भारतीयाधिशासनसंरक्षकतायां प्रकाशितम्
Published under the auspices of Govt. of India

श्रीमद्भगवत्पतञ्जलिमहर्षिप्रणीते

व्याकरणमहाभाष्ये

प्रथमः खंडः

प्रकाशकः
मोतीलाल बनारसीदास
दिल्ली :: पटना :: वाराणसी

भारतीयाधिशासनसंरक्षकतायां प्रकाशितम्
Published under the auspices of Govt. of India

श्रीमद्भगवत्पतञ्जलिमहर्षिप्रणीते

व्याकरणमहाभाष्ये

प्रथमः खंडः

बंगलो रोड, जवाहर नगर, दिल्ली-७
नैपाली खपरा, वाराणसी (उ०प्र०)
अशोक राजपथ (सम्मुख पटना कालेज) पटना

प्रथम संस्करण : १९६७
This book has been published under the scheme of reprinting of important out-of-print Sanskrit Books sponsored by the Government of India
Price Rs. 19-64 for complete set of 3 pts.

श्री सुन्दरलाल जैन, मोतीलाल बनारसीदास, बंगलो रोड, जवाहरनगर, दिल्ली-७ द्वारा प्रकाशित तथा श्री शान्तिलाल जैन, श्री जैनेन्द्र प्रेस, बंगलो रोड, जवाहरनगर, दिल्ली-७ द्वारा मुद्रित ।

डा० परमेश्वरदीन शुक्ल
संयुक्त शिक्षा सलाहकार

शिक्षा मंत्रालय
भारत
MINISTRY OF EDUCATION
INDIA
नई दिल्ली

दिनांक : 21 मार्च, 1967

आमुखम्

संस्कृतज्ञानस्य प्रसारे प्रमुखा बाधाऽस्ति भूयसामावश्यकानां ग्रंथानामलभ्यता दुर्लभता वा । इमां बाधामपनेतुकामेन केन्द्र-शिक्षामंत्रालयेन ग्रन्थानामीदृशां पुनर्मुद्रणस्य विस्तृता योजना निरमायि । तस्यामेव योजनायां प्राकाश्यमायाति विपश्चितां पुरः पुनर्मुद्रितं श्रीमद्भगवत्पतञ्जलिविरचितं महाभाष्यम् । अध्येतॄणां सौकर्यार्थं बृहत्परिमाणस्यापि पुस्तकस्यास्य मूल्यं स्वल्पमात्रमेव स्थिरीकृतम् ।

आशास्महे प्रयत्न एष नूनमेवोल्लासयिष्यति मनांसि सुधियामिति ।

परमेश्वरदीन शुक्लः

श्रीमद्भगवत्पतञ्जलिमुनिविरचितं
महाभाष्यम् ।

कैयटप्रणीतप्रदीपप्रकाशितम् ।
नागोजीभट्टविरचितोद्योतसहितम् ॥
प्रथमाध्याये प्रथमपादे प्रथमम्—
पस्पशाह्निकम् ।

(प्रदीपः)

सर्वाकारं निराकारं विश्वाध्यक्षमतीन्द्रियम् । सदसद्रूपतातीतमदृश्यं माययावृतैः ॥ १ ॥
ज्ञानलोचनसंलक्ष्यं नारायणमजं विभुम् । प्रणम्य परमात्मानं सर्वविद्याविधायिनम् ॥ २ ॥
पुरुषाः प्रतिपद्यन्ते देवत्वं यदनुग्रहात् । सरस्वतीं च तां नत्वा सर्वविद्याऽधिदेवताम् ॥ ३ ॥
पदवाक्यप्रमाणानां पारं यातस्य धीमतः । गुरोर्**महेश्वर**स्यापि कृत्वा चरणवन्दनम् ॥ ४ ॥
महाभाष्यार्णवावारपारीणं विवृतिप्लवम् । यथागमं विधास्येऽहं **कैयटो जैयटा**त्मजः ॥ ५ ॥
भाष्याब्धिः क्वातिगम्भीरः क्वाहं मन्दमतिस्ततः । छात्राणामुपहास्यत्वं यास्यामि पिशुनात्मनाम् ॥ ६ ॥
तथापि हरिबद्धेन सारेण ग्रन्थसेतुना । क्रममाणः शनैः पारं तस्य प्राप्तोऽस्मि पङ्गुवत् ॥ ७ ॥

(उद्द्योतः)

नत्वा साम्बशिवं देवीं वागधिष्ठानिकां गुरून् । पाणिन्यादिमुनीन् वन्द्यान् पितरौ च **सतीशिवौ** ॥ १ ॥
नागेशभट्टो नागेशभाषितार्थविचक्षणः । **हरिदीक्षित**पादाब्जसेवनावाप्तसन्मतिः ॥ २ ॥
याचकानां कल्पतरोररिकक्षहुताशनात् । शृङ्गवेरपुराधीशा**द्रामतो** लब्धजीविकः ॥ ३ ॥
नाविस्तीर्णं न विस्तीर्णं मध्यानामपि बोधकृत् । भाष्यप्रदीपव्याख्यानं कुर्वेऽहं तु यथामति ॥ ४ ॥

भाष्यं व्याचिकीर्षुः शिष्टाचारप्राप्तं मङ्गलं शिष्यशिक्षायै निबध्नाति—**सर्वेति** । क्त्वान्तानां पञ्चमश्लोकोत्तरार्धेनान्वयः । **सर्वाकारत्वं**—सर्वोपादानकारणत्वान्मृदादिवत् ॥ कार्यातिरिक्तदृश्यस्वरूपाभावात्—**निराकारत्वम्** ॥ कर्तृत्वात्—**विश्वाध्यक्षत्वम्**, **'स ऐक्षत'** इति श्रुतेः ॥ **अतीन्द्रियत्वं**—विगतेन्द्रियत्वेन, **'पश्यत्यचक्षुः'** इत्यादिश्रुतेः । सर्वप्रत्यक्षीकरणं तु स्वरूपचैतन्येनैव ॥ इन्द्रियाविषयत्वेन वाऽतीन्द्रियत्वम् ॥ **सदसद्रूपत्वं**=अनिर्वचनीयता, तामतीतं, तद्रहितमित्यर्थः । एवं च सदेवेति भावः ॥ नन्वीदृशमस्माभिः कुतो न गृह्यत इत्यत आह—**अदृश्य-मित्यादि ॥ १ ॥ माययावृतै**रित्यस्य कृत्यमाह—**ज्ञानेति** । **तत्त्वमस्या**दिमहावाक्यजनिताखण्डाद्वितीयसच्चिदानन्दब्रह्माकारा वृत्तिः=ज्ञानं तदेव

(छाया) उद्द्योते—प्रारिप्सितप्रतिबन्धकशमनाय कृतं समुचितस्वेष्टदेवतानत्यात्मकं मङ्गलं शिष्यशिक्षायै व्याख्यातृश्रोतॄणामनुषङ्गतो मङ्गलाय च क्रमशो निबध्नाति—**नत्वेति** । पद्योक्तसर्वद्वितीयान्तानामत्रान्वयः । अस्य च **'कुर्वे'** इत्यत्रान्वयः ॥ **वागेति** । सरस्वतीमित्यर्थः । इष्टदेवतानत्युत्तरं समुचितसरस्वतीनत्युत्तरं समुचितमुनिनतिमाह—**गुरूनित्यादि** । **गुरून्**-जगद्गुरून् ॥ गुरुनत्युत्तरं मुनिनत्युक्तेर्भेदेन व्याख्यानमयुक्तमिति बोध्यम् ॥ पित्रादिस्वर्गायाह—**पितराविति** ॥ **चः**-सर्वेषां पूज्यानां समुच्चायकः ॥ स्वकीर्तय आह—**नागेशेति** । **भट्टः**-सकलशास्त्रज्ञः । स्पष्टं चेदं **वेणीसंहरण**व्याख्यायाम् ॥ **नागेशेति** । फणिभाषितभाष्याब्धिसारज्ञ इत्यर्थः ॥ एतच्छास्त्रोप-

लोचनं, तेन संप्रेक्ष्यमित्यर्थः ॥ **नारायणमित्यादि** । सर्वनरसमूहान्तर्यामिणमित्यर्थः ॥ **सर्वविद्या**-वेदरूपा, तद्विधायिनम् ॥२॥ वचनसंदर्भ-विशेषरूपग्रन्थे समुचितत्वाद्वागधिदेवतां नमति—**पुरुषा इति** । **देवत्वं**=पाण्डित्यम् ॥ ३ ॥ संप्रदायशुद्धिं द्योतयन् गुरुं नमति—**पदेति** व्याकरणमीमांसातर्काणामित्यर्थः ॥ **धीमतः**-ऊहापोहकुशलस्य ॥४॥ **महाभाष्येति** । व्याख्यातृत्वेऽप्यस्येष्ट्यादिकथनेनान्वाख्यातृत्वादितरभाष्य-वैलक्षण्येन **महत्त्वम्** ॥ अवारपारयोर्भवम् । प्लूयतेऽनेनेति **प्लवं**-सेतुम् ॥ **यथागमम्** । संप्रदायमनतिलङ्घ्येत्यर्थः ॥५॥ औद्धत्यं परिहरति—**भाष्येति । मयूरव्यंसकादि**समासो रूपकं चेति बोध्यम् ॥ **पिशुनत्वं**-दुष्टत्वम् ॥६॥ नन्वेवं कथं प्रवृत्तिरत आह-**तथापीति** । तत्रत्यसारांश एवात्र निबद्ध इति भावः ॥ **शनैरित्य**नेनात्यन्तग्रन्थासंकोचः । **पङ्गुवदित्य**नेन व्याख्येयांशापरित्यागो व्याख्यानस्याविस्तृतत्वं च बोध्यते ॥७॥

योगितया प्राधान्येन वाऽऽह—**हरिदीक्षितेति** ॥ सदा बुद्धिस्थैर्याय तदुपयोगिनस्तस्य स्वर्गावाप्तये चाह—**याचकेति** ॥ **कक्षं**-तृणम् ॥ **रामतः**-रामसिंहवर्मतः । दानशूरत्वं रणशूरत्वं उभयसाधकं लक्ष्मीवत्त्वं च क्रमेणात्र प्रतिपादितम् ॥ तत्राभिधेयं प्रतिज्ञातुं प्राचीनव्याख्या-नामनादेयत्वायाह—**नावीति** ॥ **अपि**ना कनिष्ठपरिग्रहः ॥ **भाष्येति** । द्वन्द्वोत्तरं षष्ठीतत्पुरुषः ॥ प्राचीनव्याख्याकर्तृवैलक्षण्यसूचकः **'तु'**—शब्दः ॥ तत्त्वं चोक्तरीत्या बोध्यम् ॥ **यथामति**-इत्यनेनाज्ञाननिरासः ॥

क्त्वान्तेति । तदर्थानामित्यर्थः । नमःपदेनैव तत्प्रतीतौ तस्य कार्याव्यवहितपूर्वक्षणवृत्तित्वरूपकारणत्वबोधनायोपादानम् । अनेन ग्रन्थारम्भे मङ्गलस्यावश्यकर्तव्यत्वं सूचितमिति बोध्यम् ॥ **उत्तरार्धेनेति** । तदुत्तरार्धप्रतिपाद्यप्रधानवाक्यार्थक्रिययेत्यर्थः ॥ विरोधपरि-हाराय मतभेदं कल्पितमुपेक्ष्य वास्तवं प्रकारमाह—**सर्वोपेति । 'यतो वा-'** इत्यादिश्रुतेः । तथा च बहुव्रीहिः, तत्पुरुषो वा ॥ **मृदेति** । मध्यमणिन्यायेनान्वेति ॥ तत्राद्ये साधर्म्ये दृष्टान्तः, अग्रे वैधर्म्ये ॥ तदन्यस्वरूपसत्त्वादाह—**दृश्येति** । बहिरिन्द्रियवेद्येत्यर्थः । तथा-चात्रापि प्राग्वत्समासद्वयं बोध्यम् ॥ प्राग्वदाह—**कर्तृत्वादिति** ॥ **श्रुतेरिति** । अनेन बहुव्रीहिः सूचितः ॥ अतीन्द्रियत्वं नेन्द्रियाविषय-त्वेन, अदृश्यमित्यस्य वैयर्थ्यापत्तेरत आह—**विगतेन्द्रीति** ॥ **अचक्षुः**-चक्षुरिन्द्रियशून्यः । **आदिना—'स शृणोत्यकर्णः'** इत्यादि-परिग्रहः ॥ नन्वेवं प्रागुक्तश्रुतिविरोधोऽत आह—**सर्वेति** ॥ विश्वं साक्षात्कुर्वन्नपि नासदादिवदिन्द्रियद्वारा किं तु तथेति भावः ॥ **'यतो वाचः'** इति श्रुत्यनुरोधेन विनिगमनाविरहादाह—**इन्द्रियेति** । तस्य वैयर्थ्यं परिहरिष्यते ।

प्रदीपे—अस्य कारणत्वेऽपि न मायातुल्यत्वमित्याह—**सदिति** ॥ अत्र दण्डी—"अनेन तद्वदनिर्वचनीयत्वं निरस्तम् । तथा हि—सद-सच्छब्दौ मिथोविलक्षणवाचकौ । तथा च तज्जाऽनिर्वचनीयता । यद्वा—**सत्**-पृथ्व्यादित्रयम्, **असत्**-वाय्वाकाशद्वयम्" इति । तन्न, **"नानिर्वचनीयस्य ख्यातिस्तदभावात्"** इति सांख्यसूत्रेण तन्निरासात् । अत एव **"असत्तु मृगतृष्णावत्"** इत्येवोक्तम् । न त्वनिर्वचनीयत्वमितीति **'स्त्रियाम्'** इति सूत्रे भाष्ये । तत्र सत्त्वमधिष्ठानब्रह्मगतमारोपितम्, असत्त्वं वास्तवम् । विस्तरस्तत्रैव बोध्यः ॥

उद्द्योते—तदेतद्ध्वनयन्नाह—**सदित्यादि** ॥ **नन्विति** । अनेन वैयर्थ्यमपि परिहृतम्, दृशधातोर्ग्रहणपरत्वात् ॥ १ ॥ सर्वेषां न परोक्षमिति सूचनायोक्तं विशेषणमित्याह—**माययेति** ॥ बहुव्रीहावनन्वयादेराह—**तदेवेति** ॥ **सर्वेति** । तथाच 'नारायणो विष्णुरजो ब्रह्मा विभुर्महेश्वरः' इति तेषां पालनकर्तृत्वमपि तदधिष्ठितत्वेनेति बोध्यम् ॥ तत्फलमाह—**सर्वेति** ॥ तद्व्याचष्टे—**वेदेति** । तन्त्रादेः श्रुतिविरुद्धस्याप्रमाणत्वात् विरुद्धस्य तेनैवासंग्रहात्त्यागः ॥ २ ॥ **'पुरुषा देवत्वम्'** इति कठिनकोमलशब्दोल्लेखेन वज्रस्यापि द्रवीभावो यतः किमस्येति सूचितम् ॥ वस्तुतो देवत्वस्याभावादाह—**पाण्डित्यमिति** ॥ ३ ॥ **गुरुमिति** । अनेन सर्वविद्यालाभ एकस्मादेवेति सूचितम् ॥ वैयर्थ्यं परिहरति—**ऊहेति** ॥

कैयटे-**अपिः**—चार्थे ॥ ४ ॥ अभिधेयं प्रतिजानीते—**महेति**-कैयटे ॥

ख्यातृत्वादिति । अविरोधादिति भावः ॥ **महत्त्वमिति** ॥ एतेन ग्रन्थतोऽर्थतश्च महत्त्वमिति विवरणोक्तमपास्तम् ॥ तद्भिन्ना तेन समासः, गुरुकुलवद्वृत्तिरिति सूचयन्नाह—**अवारेति** ॥ प्लवनकर्तृत्वेन तत्त्वस्य नौकादौ सत्त्वेऽपि तस्यावारपारीणत्वासंभवादाह—**प्लूयेति** ॥ **इति**-इतिहेतोः । रूपकमुभयत्र ॥ श्रुत्याद्यनतिक्रमस्यानुपयुक्तत्वादाह—**संप्रेति** ॥ ५ ॥

रूपकमिति । एतेनातिगम्भीरत्वस्य साधारणधर्मस्योपादानात्कथमुपमितसमास इत्याशङ्क्य तेन तत्त्वं न विवक्षितं किंत्वन्यथेति दीक्षिता-द्युक्तमपास्तम् ॥ सूचकत्वस्याफलत्वादाह—**दुष्टत्वमिति** ॥ ६ ॥ सारपदस्वारस्यमाह—**तत्रत्येति** ॥ ७ ॥

(शास्त्रप्रयोजनाधिकरणम्)

(भाष्यम्)

अथ शब्दानुशासनम् ।

अथेत्ययं शब्दोऽधिकारार्थः प्रयुज्यते । शब्दानुशासनं नाम शास्त्रमधिकृतं वेदितव्यम् ॥

(प्रदीपः) भाष्यकारो विवरणकारत्वात् व्याकरणस्य साक्षात्प्रयोजनमाह—**अथ शब्दानुशासनमिति** । प्रयोजनप्रयोजनानि तु रक्षोहादीनि पश्चाद्वक्ष्यन्ते ॥

स्ववाक्यं व्याख्यातुं तदवयवमथशब्दं तावत् व्याचष्टे—**अथेत्ययमिति** । इतिशब्दोऽथशब्दस्य स्वरूपेऽवस्थापनाय प्रयुक्तः । एवं हि पदान्तरैः सामानाधिकरण्येन संबन्धे सति 'अथ'शब्दो व्याख्यातुं शक्यते । स्वरूपेऽवस्थितश्च सर्वनाम्ना परामृश्यते—**'अयं'** इति ॥ **शब्द इति** । स्वरूपकथनं विस्पष्टप्रतिपत्त्यर्थम् ॥ **अधिकारार्थ इति** । अधिकारः=प्रस्तावः, योऽत्यन्तेनास्य प्रयोजनमित्यर्थः । निपातानां च द्योतकत्वं वाक्यपदीये निर्णीतम् ॥ अथशब्दस्याधिकारार्थत्वे यो वाक्यार्थः संपद्यते तं दर्शयति—**शब्दानुशासनमिति** । अनेकक्रियाविषयस्यापि शब्दानुशासनस्य आरभ्यमाणता 'अथ'शब्दसंनिधाने प्रतीयते । व्याकरणस्य चेदमन्वर्थं नाम—'शब्दानुशासनं' इति । अत्र चाचार्यस्य कर्तुः प्रयोजनाभावादनुपादानादुभयप्राप्त्यभावात् न **'उभयप्राप्तौ कर्मणि'** इत्यनेन षष्ठी, अपि तु **'कर्तृकर्मणोः कृति'** इत्यनेनेति **'कर्मणि च'** इति समासप्रतिषेधाप्रसङ्गात् इध्मप्रव्रश्चनादिवत्समासः ॥

(उद्द्योतः) यद्यपि पाणिनिना **"ब्राह्मणेन निष्कारणः"** इत्यादिश्रुतेः संध्योपासनादाविव प्रत्यवायपरिहारार्थितयैवोत्तमाधिकारिप्रवृत्तिसंभवात् प्रयोजनं नोक्तम् । वार्तिककृताऽपि **शास्त्रपूर्वके प्रयोगे धर्मः'** इत्यनेन मध्यमाधिकारिणः परमप्रयोजनं दर्शितम् । भगवांस्तु विवरणकारत्वान्मन्दाधिकारिणां प्रवृत्तेः प्ररोचकप्रयोजनप्रतिपत्तिप्रवणत्वात् व्यवहितेषु स्वर्गापूर्वादिष्वनाश्वासात् साक्षात्प्रयो-

---

ननु **'वृद्धिरादैच्'** इत्यत आदावेवोच्यतामत आह—कैयटे—[प्र० १ मपङ्क्तौ] **व्याकरणस्येति** ॥ तथा चोपोद्घाततया समस्तशास्त्रारम्भे कथनस्य योग्यतयाऽत्राभिधानं युक्तमिति भावः ॥

कैयटे [२ यप०] **प्रयोजनमाहेति** । प्रयोजनं ब्रुवन् शास्त्रारम्भप्रतिज्ञामाहेत्यर्थः ॥ अनेन मूलानुक्तमपि व्याख्यात्राऽवश्यं दर्शनीयमिति सूचितम् ॥

इतिशब्दस्यादिहेतुप्रकारसमाप्त्याद्यर्थकत्वात्पदार्थविपर्यासकृत्त्वाच्चाह—[प्र० ४ थंप०] **इतीति** ॥

अथाधिकारार्थ इत्युक्तेऽनन्तरं कश्चिच्छब्दस्तदर्थ इति गम्येतात आह—[प्र० ६ ष्ठप०] **अथशब्द इति** ॥

अधिकारो न प्रतिपादनम्, तथाऽकृतत्वादत आह—कैयटे—[प्र० ९ प०] **प्रस्ताव इति** ॥

ननु वाचकत्वमेव किं नात आह—[प्र० १० प०] **निपातानां चेति** ॥

कैयटे [प्र० ११ प०] **संपद्यते**=वाच्यो भवति ॥ एतेन 'प्रसूयते इति शाब्दः, अयमार्थः' इत्यपास्तम् ॥ **तमिति** । तत्रैव शब्दानुशासनपदार्थं प्रतिपादयमिति शेषः ॥

कैयटे—[प्र० १३ प०] **भ्यमाणतेति** । **'वर्तमानसामीप्ये'** इति भूते लट् ॥ स्वरीत्याऽऽह—**सन्निरिति** । तत्रैव ।

कैयटे [प्र० १५ प०] **प्रयोजनेति** । प्रयुज्यते येन तत्तथा, प्रयोगसाधकफलभावादित्यर्थः ॥ नन्विन्द्रादिव्यावृत्तिः फलमत आह—तत्रैव—**अनुपेति** ॥ अनुक्तेश्चेत्यर्थः । सत्यपि फले 'शब्दानामिदमनुशासनं नार्थानाम्' इत्यर्थनिवृत्तौ तात्पर्यात्सतोऽपि कर्तुरविवक्षितत्वेन तत्संभवादिति यावत् ॥

[उ० २ यपङ्क्तौ] **श्रुतेरिति** । वेदाध्ययनवद्व्याकरणाध्ययने नित्यतया प्राप्ते इति शेषः ॥ **एवेन** प्रयोजनप्रतिपत्तिनिरासः । तदुक्तं भट्टैः—

तस्माद्विज्ञायमानत्वाद्नोक्तं शास्त्रकृता स्वयम् ।
शास्त्रेण सर्वशब्दानामन्वाख्यानप्रयोजनम् ॥ इति ॥

[उ० ३ यप०] **अपिस्त्वर्थे** ॥ **परमेति** । पार्यन्तिकेत्यर्थः ॥ परम्परया प्रयोजनमिति यावत् ॥

[उ०५मप०] समाधत्ते—**तथापीति** ॥ **भगवान्**-भाष्यकारः ॥ ननु ताभ्यामनुक्तं किमित्युच्यतेऽत आह—**विवरणेति** ॥ **प्रवृत्तेरिति** । ननु न फलकथनं प्रवृत्तावङ्गम्, किं तु तद्वत्ताज्ञानम् । तच्चाचार्यप्रवर्तनेनानुमित्यात्मकं सुलभमिति वेदाध्ययनादौ माणवकस्येवात्र प्रवृत्तिः सूपपादा । तदुक्तम्—

हितकारिभिरेवासौ ज्ञायमानः प्रयोजकः ।
कर्त्राऽविज्ञायमानोऽपि नैव स्यादप्रयोजकः ॥ इति ॥

किंचाचार्यो यथासस्ताहि तत्प्रवर्तनयैव तदव्यभिचारेण सा । अन्यथा नाप्तस्तर्हि शतशः कथ्यमानेऽपि तस्मिन्विप्रलम्भकत्वाशङ्कया न सा । तस्माद्यत्र तत् व्यक्तम्, तत्र सा लोकानाम् ॥ नन्विदमेवावश्यं वाच्यं ग्रन्थादाविति चेत् । भाष्य आप्तत्वफलवत्त्वयोः सामान्यतो ज्ञानेऽपि प्रवृत्तिविशेषे तद्विशेषज्ञानमेवाङ्गम्, **'सामान्ये सामान्यं विशेषे विशेषः प्रयोजकः'** इति न्यायात् । नहि किंचिद्स्तीति अन्यजिज्ञासुरन्यत्र प्रवर्तते । अत एव सर्वत्र तद्वदित्येव नोच्यते किंतु तद्विशेष एव कथ्यते—**'अथातो धर्मजिज्ञासा'** इत्यादिना ॥ एवं चात्र नियमेन प्रवृत्त्यर्थमस्यासाधारणं तद्वाच्यमेव ॥ एतेन **'विषयं प्रादर्शयत्'** इति कौस्तुभाद्युक्तमपास्तमिति दिक् ॥ तदेतद् ध्वनयन्नाह—**प्ररोचकेति** ॥ **प्रवणत्वात्**—तदधीनत्वात् ॥ ननु विश्वजिन्न्यायेन स्वर्ग एव फलमास्तामत आह—**व्यवहितेष्विति** । व्यवहितफलेष्वित्यर्थः ॥ क्वचित्तथैव पाठः ॥ वस्तुत आद्य एव पाठः । स्वर्गे तत्त्वस्य सत्त्वात् । अपूर्वे तत्साधनत्वात्तत्त्वं बोध्यम् ॥

न्यूनतां परिहरति—[उ० ७ मप०] **तत्रेति** । प्रयोजनादीनां मध्ये भाष्यवाक्ये वेत्यर्थः । तथा च त्रिमुनिसंग्रहात्मकव्याकरण-

जनं शब्दव्युत्पत्तिलक्षणं वदतीत्याह—**भाष्यकार इति** । तत्र शब्दज्ञानरूपे प्रयोजन उक्ते **विषयोऽप्युक्त एव**, शास्त्रजन्यज्ञानविषयस्यैव शास्त्रविषयत्वात्–इति बोध्यम् । तज्जिज्ञासुरधिकारी, प्रतिपाद्यप्रतिपादकभावः **संबन्ध** इति–अर्थादेव लब्धम् ॥ ननु '**कानि**

पाद्यप्रतिपादकभावः संवन्ध इति अर्थादेव लब्धम् ॥ ननु **कानि**
पुनरित्यादिना प्रयोजनानि वक्ष्यति । तेन पौनरुक्त्यमत आह—**साक्षादिति** । तदेवाह—**प्रयोजनप्रयोजनानीति** । **व्याख्यातु**मित्यस्य शब्दानुशासनमित्यादिनेति शेषः ॥ **तावत् प्रथमम्** । **व्याचष्टे इति** । पदार्थज्ञानायानन्तर्याद्यर्थकत्वनिरासाय चेति शेषः। भाष्यत्वादेव च स्ववाक्यव्याख्यानमिति भावः ॥ नन्वितिं विनाऽप्यथशब्दोऽधिकारार्थ इत्येवोच्यतामत आह—**एवं हीति** । पदा-

न्वैः—शब्दपद–अधिकारार्थंदप–प्रयुज्यत इतिपदैः ॥ **व्याख्यातुमिति** । अधिकारार्थत्वेनेति शेषः ॥ '**अथेतिशब्दोऽधिकारार्थः**' इत्युक्ते आनन्तर्याद्यर्थकत्वमप्रमाणमिति भ्राम्येदतः '**अयं**' इति भाष्ये । योऽयमस्मिन् वाक्ये स इत्यर्थः ॥ **विस्पष्टेति** । '**नवेति**-' इत्यादावर्थपरताया दर्शनेन तथा भ्रमं निवर्तयितुमित्यर्थः ॥ ननु निपातानां द्योतकत्वादभिधेयवाच्यर्थशब्दोऽनुपपन्नोऽत आह—**अधिकार इति** ॥ **प्रस्ताव इति** । प्रारम्भ इत्यर्थः ॥ स चार्थाद्व्याख्यायमानस्य । **अथ**शब्दः प्रयोजनवाचीति भावः ॥ **निपातानां च द्योतकत्वमिति** । निपातानां द्योतकत्वं चेत्यर्थः । उपसर्गातिरिक्तनिपातानां द्योतकत्ववाचकत्वोभयस्वीकारस्य '**अव्ययं विभक्ति–**' इतिसूत्रे भाष्ये स्पष्टत्वात् । उपसर्गाणां तु द्योतकत्वमेवेति स्पष्टं '**गतिर्गतौ**' इति सूत्रे

र्थोच्यमानमिदं प्रयोजनं स्वकृतिमपि गोचरयति '**स्वाध्यायोऽध्येतव्यः**' इतिवत् ॥ एतेन अस्वातन्त्र्यात् तस्य तदुक्त्या स्वस्यापि तद्वत्तासिद्धिरिति नारायणोक्तमपास्तम् । इत्यादिकथनेन स्वातन्त्र्यात् ॥ **विषयस्वादिति** । घटकत्वाच्चेत्यपि बोध्यम् ॥ **इति** । इति तु ॥ **साक्षादितीति** । अव्यवधानेन ज्ञायमानत्वादिति भावः ॥

[उ०१२प०] **तदेवाहेति** । तद्विशेषणकृत्यमेवाहेत्यर्थः॥ **प्रयोजनेति** । तस्यापि किंप्रयोजनमिति जिज्ञासायामित्यादिः ॥ **पदार्थेति** । पदार्थधियो वाक्यार्थधीहेतुत्वात् ॥ नन्वानन्तर्यमर्थः प्रसिद्ध एवात आह—**आनन्तर्याद्येति** । आदिना **मङ्गलानन्तरारम्भप्रश्नकार्त्स्न्येष्वथो अथ** इति कोशोक्तपरिग्रहः॥ **र्थकत्वेति** । तदुमेत्यर्थः ॥ तेषामसंभवात् । तथाहि—'कोट्यन्तरानुक्तेः प्रश्नार्थो न अर्थानुशासनस्यापि सत्त्वेन बाधात्, सर्वार्थो न 'सर्वेषां शब्दानाम्' इति व्याख्याने 'केषां शब्दानाम्' इत्यवतरणग्रन्थासंगतिः । प्राक्कस्यचिदप्रकृतत्वेनासंभवादानन्तर्यार्थत्वमपि न, प्रागुक्तानन्तर्यपरत्वस्य तत्र तत्र संभवे अनुक्तानन्तर्यपरत्वेऽव्यवस्थापत्तेः । विषयादिकथनेनैव तद्विषयजिज्ञासानन्तर्यशास्त्राध्ययनादेर्न्यायसिद्धं सूचितमेवेति तदुक्त्यानर्थक्याच्चेति ॥ ननु धर्मजिज्ञासायां वेदाध्ययनानन्तर्यवदत्र कुतो नेति चेन्न । वैषम्यात् । तत्र तथात्वे एकाधिकारिकल्पनालाघवं चातुर्वर्ण्याधिकारनिवृत्तिश्च प्रयोजनम् ॥ नैवमत्र व्याकरणस्य वेदाङ्गत्वश्रुतेः प्रधानाधिकारिण एवाङ्गेऽप्यधिकारात् । नापि प्रमाणम् । तथाहि विना वेदाध्ययनं तदर्थविचारो न संभवतीति तदानन्तर्यमाक्षिप्यते अताद‍ृशस्यार्थानवधारणे तत्र जिज्ञासानुदयात् नैवमत्र, अनधीतवेदस्यापि लौकिकवैदिकप्रयोगाङ्गभूतसाधुज्ञानायैतदध्ययनसंभवात् । तथा च वक्ष्यति—**पुरा कल्प** इत्यादि ॥ अत एव चात्रानन्तर्यकल्पना विरुद्धा ॥ किंच वेदाध्ययनसमकालतापि स्मर्यते—"**अनध्यायेष्वङ्गान्यधीयीत**" इति । **अत ऊर्ध्व**मित्यादिमनुश्च ॥ अन्यत्रापि **प्रधानमध्येऽङ्गानामनु**ष्ठानं दृश्यते-इति ॥

[उ० १६ प०] **एवेन 'अयम्'** इत्यस्य निरासः ॥ **एवं हीतीति** । यत एवं सतीत्यर्थः । किंचानन्तरं कश्चिच्छब्द इत्येव प्रतीयेत । किं च म ं ं म तदर्थ एवेत्येव प्रतीयेत, तत्तु न, उक्तहेतोः ॥ तत्तु 'अथ ।ब्द' इत्युक्तावन्योऽयमेव वा'–इति संदेहापत्तिः । तत्र

इतरभावेऽर्थपरत्वेन स्वरूपपरत्वे चान्योपस्थापकाभावेन च संदेहानुदयात् । इतिं विना समःतोऽपि दुर्लभः, तदेतद् ध्वनयन् '**स्वरूपेऽवस्थानस्य प्रयोजनान्तरमाह—स्वरूप इति**' इति विवरणोक्त्यसांगत्यं प्रतिपादयंश्चाह—**अथेतीति** ॥ अथेत्यधिकारार्थ इत्युक्तेऽप्येवं भाष्ये व्याख्यानासंगतिश्च, अन्यत्रोक्तार्थप्रतीतेरिति भावः । अत ए। '**तदवयवम्**' इति प्रागुक्तं कैयटे ॥

[उ० १९ प०] **योऽयमिति** ॥ शास्त्रारम्भप्रतिज्ञापरवाक्ये उपात्त इतिना स्वरूपेऽवस्थापितः, स इतीत्यर्थः । शब्दपदादिसामानाधिकरण्यात्तस्य पुंस्त्वम् ॥ एतेन स्वरूपपरत्वान्नपुंसकत्वमुचितमित्यपास्तम् ॥ एतेन कैयटे [७प०] चस्त्वर्थे उक्तफलार्थो न तदर्थ इति सूचितम् ॥ [२० प०] **परताया इति** । इतिसमभिव्याहृतस्येति शेषः ॥ लोकेऽर्थपरत्वस्यौत्सर्गिकत्वेन दृष्टान्तवैषम्यादाह–**भ्रममिति** ॥

[उ०२३प०] स्तुतिभ्रमनिरासाय तदर्थमाह—**प्रारम्भ इति** ॥ **मानस्येति । अथशब्दानुशासनमित्युक्तेः** ॥

सिद्धान्ताविरोधाय प्रकृतानुरोधेन **चो** व्युत्क्रमे–इत्याह—[उ० २४ प०] **निपातानामिति** ॥ उपसर्गभिन्नानामित्यर्थः ॥ **चेन** वाचकत्वसमुच्चयः । तदाह—**उपेत्यादिना** ॥ एतेन—क्रियान्वयिनामेव तेषां तत्त्वस्य भ्वादिसूत्रे भगवता व्यवस्थापितत्वेन सर्वेषां तत्त्वे मानाभावेनात्र तत्त्वे दोषाभावेन वाचकपदासमभिव्याहारे तत्त्वस्य दुर्वचत्वेनार्थस्य द्योत्यत्वादिभेदेन त्रैविध्येन तदसमभिव्याहारे तथा व्याख्यानानौचित्येन च चिन्त्योऽयं कैयट इति रत्नप्रकाशोक्तमपास्तम् । उक्तहेतोः । **अनन्यलभ्य** इति न्यायेन तत्त्वस्यायुक्तत्वात् । वाचकस्याध्याह्रियमाणादः सत्त्वात् । सिद्धान्तस्य वक्ष्यमाणत्वाच्चेति दिक् ॥ तद्भेदनिवेशफलमाह—[उ० २६ प०] **उपेति** ॥ [उ० २८ प०] **अत एव–तेषु** ताद‍ृशेषूभयसत्त्वेन वाचकत्वाङ्गीकारादेव ॥ अन्यत्‌ तत्त्वं कौस्तुभे मत्कृततद्व्याख्याने च स्पष्टम् ॥

ननु मङ्गलार्थत्वस्यापि संभवादधिकारार्थ त्ययुक्तमत आह—**प्रयुज्यत इति** भाष्ये ॥ अनेन तत्सिद्धिः ॥

तत्फलितमाह—[उ० २९ प०] **प्रारम्भेति** । भूतेत्यादिः ॥ अनेनाधिकारादिपदानां ताद‍ृशकर्मप्रत्ययान्तत्वं सूचितम् ॥ अत एव [भाष्ये] '**अधिकृतम्**'इत्युक्तिसंगतिः ॥ [उ० ३० प०] **मङ्गलत्वमिति** ॥ स्वरूपेणैवेति भावः ॥ अर्थतस्त्वधिकारार्थता,

भाष्ये-इति तत्रैव निरूपयिष्यामः। अत एव 'साक्षात्क्रियते गुरुः'
इत्यादि संगच्छते॥ प्रारम्भक्रियाविषयत्वद्योतकस्यापि अथशब्दस्या-
न्यार्थं नीयमानदध्यादिवत् मङ्गलत्वमपीत्युभयार्थमथशब्दः प्रयुज्यत
इति फलितम्॥

परे त्वत्र वाचकत्वमेवेच्छन्ति। 'अधिकृतं' इति च तदर्थं
वदन्ति। भाष्ये **'प्रयुज्यते'** इत्यनेन वर्तमाननिर्देशेन सर्वलोक-
सिद्धमस्याधिकारार्थत्वं, न तु वृद्ध्यादिवत्पारिभाषिकमिति ध्वनितम्॥
ननु विवरणे 'अधिकृतं' इत्यधिकं, वाचकपदाभावात् द्योतकतानु-
पपत्तिश्च-इत्यत आह—**अनेकेति**। उच्यते-श्रूयते-क्रियते-इति॥
प्रतीयत इति। एतावतैव द्योतकत्वमिति भावः॥ ननु भावसाधन-
स्यानुशासनपदस्य शास्त्रपदेन सामानाधिकरण्यमनुपपन्नमत आह—
व्याकरणस्य चेति। अन्वर्थत्वात्प्रयोजनाभिधानोपपत्तिः। अनुशि-
ष्यन्ते=असाधुशब्देभ्यो विविच्य ज्ञाप्यन्तेऽनेनेति करणल्युडन्ततया
शास्त्रपदेन सामानाधिकरण्यमिति भावः। इदमेव ध्वनयितुं भाष्ये
नामपदोपादानम्। नामनामिनोरभेदात् 'नाम-शास्त्रम्' इति सामा-
नाधिकरण्यम्॥ अनेनैवापभ्रंशानामविषयत्वं सूचितं ध्वनीनां च॥

'केषाम्-' इति प्रश्नस्तु-लौकिकमात्रविषयं शाकटायनादिशास्त्रम-
धिकृतम्, उत वैदिकमात्रविषयं प्रातिशाख्यम्-इति-इति **परे**॥ ननु
'कर्मणि च' इति निषेधात्कथं कर्मषष्ठ्यन्तेन समासोऽत आह—
'आरम्भ-**मत्र चाचार्यस्येति**। उभयोरुपादान एवोभयप्राप्तिरिति 'आरम्भ-
माने-' इति सूत्रे भाष्ये स्पष्टम्॥ **'कर्तृकर्मणोः-'** इति षष्ठ्यामपि
समासनिषेधः कुतो नेत्यत आह—**इष्मेति**। चस्य-इति-अर्थकतया
कर्मणीत्युच्चार्य विहितषष्ठ्यैव समासनिषेध इति भावः॥ भाष्ये **शास्त्र**-
मित्यस्य 'कर्तव्यत्वेन' इति शेषः। 'विवरणकारत्वात् व्याख्यातव्य-
त्वेन' इति शेष उचित इत्यन्ये॥ शास्त्रत्वं चास्य साधुत्वरूपैक-
प्रयोजनसंबद्धत्वाद्बोध्यम्॥

(आक्षेपभाष्यम्)

केषां शब्दानाम्?

**(प्रदीपः) शब्दशब्दस्य सामान्यशब्दत्वात् विना प्रकरणा-
दिना विशेषेऽवस्थानाभावात् तन्त्रीशब्दकाकवाशितादीनामनु-
शासनप्रसङ्ग इति मत्वा पृच्छति—केषामिति। उत्तरपदार्था-
न्तर्गतस्यापि पूर्वपदार्थस्य बुद्ध्या प्रविभागात् प्रत्यवमर्शः। यथा
राजपुरुष इत्युक्ते 'कस्य राज्ञः?' इति॥**

तदाह—**पीत्युभयेति**॥ **अथशब्द इति**। अन्यथा 'अधिकृतं
शब्दानुशासनम्' इत्येव वदेत्। अर्थतो मङ्गलत्वे तत्त्वं न स्यात्, सकृ-
त्प्रयुक्तत्वात्। तथा च श्रुत्या मङ्गलार्थप्रयुक्तस्य तस्य व्याख्यानमुचित-
मेवेत्येवमुक्तमिति भावः॥ ननूक्तभाष्यादुभयसिद्धौ वाचकत्वमेवात्र
कुतो न, तत्र बाधकसत्त्वे एव द्योतकत्वाङ्गीकारेण प्रकृते तदभावात्।
साक्षात्क्रियते-इत्यादौ तु बाधकमिति न तत्त्वम्॥ न च प्रमाणानां
सामान्ये पक्षपातेन निपातत्वेनैव द्योतकता, प्रमाणस्य सामान्यावच्छे-
देन प्रवृत्तौ बाधकाभावसहकृतस्यैव लाघवस्य बीजत्वेन प्रकृते वाचक-
पदसमभिव्याहाराभावरूपबाधकस्य सत्त्वेनाथशब्दभिन्ननिपातत्वेन
तस्या विशेष्यीकरणेनादोषात्। परेषां **नामार्थयोरि**तिव्युत्पत्तौ तन्नि-
वेशवत्॥ एवमन्यत्रापि बोध्यम्॥ अन्यादृशद्योतकत्वस्य चागतावङ्गी-
कारात्॥ यत्तु—

> **चतुर्विधे पदे चात्र द्विविधस्यार्थनिर्णयः।**
> **क्रियते संशयोत्पत्तेर्नोपसर्गनिपातयोः॥**
> **तयोरर्थाभिधाने हि व्यापारो नैव विद्यते।**
> **यदर्थद्योतकौ तौ तु वाचकः स विचार्यते॥**

इति भट्टैरुक्तम्। तन्निपातांशे बाहुल्याभिप्रायम्, न तु सार्व-
त्रिकम्॥ वाक्यपदीयादौ निपातानां द्योतकत्वकथनमप्येवमेव॥
न चार्धजरतीयता, द्योतकत्वस्यापि तु स्वादावसत्त्वेन द्योतकत्वमद्यो-
तकत्वमित्येवं तत्त्वस्य स्वमतेऽपि सत्त्वात्। अथेत्यस्यैवानन्तर्यादि-
वाचित्वं क्वचित्प्रारम्भद्योतकत्वमिति तत्त्वाच्च॥ न च तस्य वाच्यत्वे
गौरवेणान्यलभ्यत्वेन लाघवाद्द्योतकत्वमेव युक्तम्, अन्यस्य वाच-
कस्योपस्थापकाभावेन तदभावात्। प्रत्युत वाचकत्वद्योतकत्वोभय-
कल्पनजगौरवाच्च॥ न **चान्याय्यश्चानेकार्थत्वम्**, उक्तकोशाच्च-
स्यैव न्याय्यत्वात्॥ न च द्योतकत्वेनैव कोशोपपत्तिः, भवेदेवमो-
पसंदानिकशक्तिर्द्योतकत्वमिति पक्षे, न ह्यत्रोपसंदानम्। प्रादेस्तात्प-
र्यग्राहकत्वमप्युपसंदानेनैव। न च प्रकरणादिवत्तात्पर्यग्राहकत्वमेव
द्योतकत्वम्, तस्यागतिकगतित्वस्योक्तत्वात्। किंचैवं सति-तद्वद-

त्रापि कोशो न स्यात्, स्याद्वाऽत्रैव तत्राप-इति कोशानुपपत्ति-
स्तदवस्थैव॥ अथान्यलभ्यत्वसहकारेण कोशोऽन्यथा नेय इति चेत्,
तर्ह्यक्षादिपदानामप्यनेकार्थे शक्तिर्न स्यात्, तत्रापि लाघवादेकत्र
शक्तिरन्यत्र लक्षणेति सुवचत्वात्। अन्यलभ्यत्वाभावस्योक्तत्वाच्च॥
तस्मादथशब्दस्य प्रारम्भद्योतकत्वं कैयटोक्तं **चिन्त्यम्**। किंचाथशब्दो
द्योत्यत्वेन बोध्यपर एवास्तु, बाधकाभावात्। अत एव **प्रारम्भं
द्योतयन्नथशब्द** इति हरदत्तेनोक्तम्॥ एवं च प्रयोजनपरत्वमपि
तस्य चिन्त्यम्-इति चेत्; अत एव सिद्धान्तमाह—[उ० ३१ प०]
परे त्वत्रेति। अथशब्दे-इत्यर्थः॥ **एवेन** द्योतकत्वनिरासः॥ नन्वेवं
तस्य प्रस्तूयत इति साध्यार्थपरत्वेन नामपदानां सिद्धार्थपरत्वहानिरत
आह—**अधीति**॥ यथैवं सति न पूर्वविरोधस्तथोक्तम्। हिरुगा-
दानेवमेवाङ्गीकाराच्च। तेषां क्रियासामानाधिकरण्येन क्रियाविशेष-
णत्वेऽपि तदवाचकत्वाच्च। अव्ययेषु नामत्वस्यासत्त्वाच्चेति दिक्॥
पारीति। मयेदानीं परिभाष्यत इत्यर्थः॥

यत्तु—नन्वधिकारार्थोऽप्यथशब्दः किमिति प्रयुज्यतेऽत आह—
अनेकेति-इति विवरणकृत्। तन्न, तत्फलस्य प्रागुक्तत्वात्।
स्वपूर्वविरोधाच्च। तद्ध्वनयन्नाह—[उ० ३३ प०] **नन्विति**॥
कैयटरीत्याऽऽह—**वाचकेति**। अस्य मध्यमणिन्यायेन पूर्वत्राप्य-
न्वयः॥ **इति**-इत्यादि॥

तद्रीत्यैवाह-[उ० ३६ प०] **एतेति**॥ वाचकपदासमभिव्याहारेऽपि
प्रकरणादिवत्तात्पर्यग्राहकत्वेनैव क्रियाविशेषाक्षेपकत्वरूपं द्योतकत्वं
'प्रादेशं विलिखति' इत्यादिवदित्यर्थः॥ प्रादेरिवोपसंदानेन द्योतकत्व-
स्यैव **एवेन** व्यवच्छेदः॥ यद्यपि लक्षणया तस्यापि संभवः, तथापि
व्याख्यानभाष्यविरोधान्न तदुक्तम्। सिद्धान्ते तु तस्य गोऽदृ-
एवेति प्रागुक्तम्॥ **भावसाधनेति**। अस्य व्याकरणप्र[illegible]भि-
धायकत्वादिति भावः॥ **अनुशेति**। किं च[illegible]। तथाभिध्य
ग्रहणम्? किंच रूढिर्योगो योगरूढिर्वेत्यपि सत्वादाह—**पदान्त**-
पदेन रूढेरेव प्रतीतौ **'प्रयोजनमात्र'** इति तत्र तस्य सार्वा[illegible]त्वं

(उद्द्योतः) **सामान्यशब्दत्वादिति** । लोकव्यवहारे ध्वनावपभ्रंशे च शब्दशब्दप्रयोगादिति भावः ॥ एतेन ध्वनिव्यङ्ग्य एव तपरसूत्रादौ शब्दशब्दप्रयोगादिदं चिन्त्यमित्यपास्तम् ॥ ननु 'व्रीहीन् प्रोक्षति' इत्यादौ सामान्यशब्दस्याप्यपूर्वीयेषु विशेषेषु प्रवृत्तिवद् वाचके साधौ तद्विशेषे प्रवृत्तिर्भविष्यतीत्यत आह—**विनेति** । व्रीहिशब्दस्य तु प्रकरणाद्विशेषे प्रवृत्तिरिति भावः । **वाशितादीनाम्**–इति आदिनाऽपभ्रंशसंग्रहः ॥ ननूत्तरपदार्थसंसृष्टपूर्वपदार्थस्य कथं सर्वनाम्ना परामर्शोऽत आह—**उत्तरपदार्थान्तर्गतस्येति** । ततः पृथगुपस्थित्यविषयस्येत्यर्थः ॥ **बुद्ध्या**–मानस्या । यद्वा वाक्यजन्यबुद्ध्या ॥

(समाधानभाष्यम्)

लौकिकानां वैदिकानां च । तत्र लौकिकास्तावत्—गौः-अश्वः-पुरुषः-हस्ती-शकुनिः-मृगः- ब्राह्मण इति ॥

वैदिकाः खल्वपि—शन्नो देवीरभिष्टये, इषे त्वोर्जे त्वा, अग्निमीळे पुरोहितम्, अग्न आयाहि वीतये- इति ॥

(प्रदीपः) सिद्धान्तवादी तु व्याकरणस्य वेदाङ्गत्वात्सामर्थ्याद्विशेषावगतिरिति मत्वाऽऽह—**लौकिकानामिति** । लोके विदिता इति 'लोकसर्वलोकाभ्यां' इति ठञ् । **अथवा** भवार्थे- अध्यात्मादित्वाट्ठञ् । वेदे भवाः-वैदिकाः । वैदिकानामपि लौकिकत्वे प्राधान्यख्यापनाय पृथगुपादानम् । यथा—**ब्राह्मणा आयाता वसिष्ठोऽप्यायात** इति वसिष्ठस्य । तेषां तु प्राधान्यं यत्नेनापभ्रंशपरिहारात् । **अथवा** भाषाशब्दानामेव लौकिकत्वमिति भेदेन निर्देशः ॥ तत्र लोके पदानुपूर्वीनियमाभावात्पदान्येव दर्शयति—**गौरश्व इति** ॥ वेदे त्वानुपूर्वीनियमाद्वाक्यान्युदाहरति—**शन्न इति** ॥

आह—**अन्वर्थेति** । तद्धटकयोगार्थादित्यर्थः ॥ अनुपूर्वकशासेर्विविच्यज्ञापने दृष्टत्वस्यान्यत्र प्रसिद्धत्वादाह—**असाध्विति** ॥ नन्वेवं नामपदासंगतिरत आह—**इदमेवेति** । अन्वर्थत्वाद्येवेत्यर्थः ॥ एतेन 'नामशास्त्रम्' इति समस्तमित्यपास्तम् । आख्यातशास्त्रत्वस्यापि सत्त्वाच्च । एतेन "नामेति प्रसिद्धौ, शब्दान्वाख्यानार्थकत्वेन प्रसिद्धं" इति नारायणोक्तमपास्तम् ॥ शास्त्रत्वं चास्यानुपदं स्फुटीभविष्यति ॥ [उ० ४२ प०] **अनेनैवेति** । तदन्वर्थत्वादिबोधकनामशब्दोल्लेखेनैवेत्यर्थः । तत्त्वस्यात्राभावादिति भावः ॥ नन्वेवं प्रश्नासंगतिरत आह—**केषामितीति** ॥ **इतीति** । इति पूर्वग्रन्थार्थसंशयाशयक इत्यर्थः । तथा च 'लौकिकानामेव, उत वैदिकानामेव' इत्याशयकः प्रश्न इति भावः ॥ कैयटाद्युक्तयसांगत्यध्वननायाह—[उ०४४श प०] **परे इति** । भाष्यानुयायिन इत्यर्थः ॥

[उ०४५श प०] **कथमिति** ॥ शब्दानुशासनमित्यत्रेति भावः ।

एतदेव ध्वनयन्नाह—[उ०४६श प०] **उभयोरिति** । प्राप्तिग्रहणात्, आश्चर्यो गवां दोहोऽगोपेन इत्यादौ यथेति भावः ॥ **इध्मेतीति** । एवं च 'तत्रापि प्रसङ्गापत्तेः' इति हेतुस्तत्रार्थे बोध्यः ॥ अपां स्रष्टेत्यादेरपि तेनैव सिद्ध्या **'कर्तरि च'** इति वैयर्थ्यापत्तेश्च ॥ न च प्रेष्यस्य कारयितेत्यादौ **'हृक्रोः–'** इति कर्मत्वाभावपक्षे कर्तृषष्ठ्यास्तन्निषेधार्थमेव तदिति वाच्यम्, **'तृजकाभ्यां'** इत्येव सिद्धेः । तृज्ग्रहणमुत्तरार्थमिति तु **'कर्तरि च'** इत्यस्य सत्त्व इत्यपि बोध्यम् ॥ ननु कथमुक्तार्थलाभोऽत आह—**चस्येत्येति** । **'कर्मणि च'** इति ननु कथमुक्तार्थलाभोऽत आह—चस्येत्येति । 'कर्मणि च' इति सत्र इति शेषः । निपातानामनेकार्थत्वादिति भावः ॥ **कर्मणीति** । सप्तम्येकवचनान्तमित्यर्थः ॥ नियमशास्त्राणां विधिरूपेण प्रवृत्तेराह—**विहितेति** ॥ **कर्तव्येति** ॥ स्वकृतिनिष्ठसाध्यत्वस्य तत्राप्यारोप इति भावः ॥ आरोपाभावकृतलाघवादाह—**विवरणेति** । इदं च सूत्रादिवत्स्वकृतेरप्यस्तीति भावः ॥ यद्यपि व्युत्पाद्यतया शब्दा एव प्रस्तुताः, न शास्त्रम्; तथापि तत्प्रतिपादकत्वाच्छास्त्रमेव प्रस्तुतमुच्यते । शास्त्रत्वं चास्य योगरूढ्या । **पदद्वयादिव्याख्यानेन** च सं... ...स्त्रम्, न च सिद्धसाधुशब्दबोधकस्यास्य प्रागुक्तभाष्यलक्षणसत्ता सूचिता ॥

'अथ ...ब्द इत्युक्तावन्... **...र्वा नित्येन कृतकेन वा ।**
तच्छास्त्रमभिधीयते ॥

इत्युक्तेरिति वाच्यम् । तस्यासार्वत्रिकत्वात् । एकफलसंबद्धार्थस्य कात्स्न्र्येन प्रतिपादकस्यैव हि सर्वत्र शास्त्रपदार्थत्वात् ॥ अन्यथा न्यायादीनां सिद्धार्थपराणामतत्त्वापत्तेः । तदभिप्रेत्याह—**शास्त्रत्वमिति** ॥ प्रवृत्त्याद्युपदेशकत्वमपि सुवचम् ॥ 'एतद्बोधिताः साधवः, तैरेव भाषितव्यम्, नासाधुभिः' इत्युपदेशादिति बोध्यम् ॥

भाष्ये–**वेदितव्यमिति** । शिष्टैरिति शेषः ॥ यद्यपि **'भवति'** इत्येवाध्याहार्यम्, तस्य सिद्धार्थपरत्वात्, तथापि यागादौ संकल्पवत् शास्त्रारम्भप्रतिज्ञारूपसंकल्पविशेषबोधनायास्याध्याहारः ॥ अनेन— आरब्धं मध्ये दुस्त्यजम्, त्यागे च विगानप्रायश्चित्ते–इति सूचितम् ॥

[उ०१मप०] ननु **तपरसूत्रे** शब्दानां ध्वनिरिति व्यङ्ग्यव्यञ्जकयोः शब्दशब्दस्य प्रयोगादन्वर्थत्वाच्चानतिप्रसङ्गोऽत आह—**लोकेति** । त्रैविध्यबोधेत्यर्थः ॥ **ध्वनाविति** । अनेनापरिस्फुटाकारादिवर्णसकशब्दपरिग्रहात्काकवाशितादीनां पृथगनुक्तिः ॥ उक्तरीत्या तत्रानतिप्रसङ्ग एवेति सूचनमेवमुक्तेः फलम् । तथा च शुद्धरूढः शब्दशब्दः । तपरसूत्रप्रयोगस्तु प्रकृताशयक इति भावः ॥

[उ०४थंप०] **विशेषेषु**–व्रीहिविशेषेषु ॥ वाचकत्वस्य सिद्धान्तेऽपभ्रंशसाधारण्यादाह—**साधाविति** ॥ **प्रकरणात्**-यागप्रकरणात् ॥

[उ०६ष्ठप०] ननु तत्र्यादिशब्दानां न तत्त्वप्रसङ्गः, प्रकृत्यादिविभागस्य तत्रासंभवात् । शकुनागमगान्धर्ववेदादिभिरेव तन्निर्णयाच्च ॥ अत एव कैयटे **'मत्वा'** इत्युक्तिरत आह—**वाशितेति** ॥ बहुवचनं तु शब्दभेदाभिप्रायम् ॥

[उ०७मप०] ननु मिलितैकदेशस्य विशेष्यस्य "सर्वनाम्नां प्रधानपरामर्शित्वं" इति नियमाङ्गीकारेण परामर्शसंभवेऽपि गुणीभूतस्य वृत्त्याद्यन्तर्गतस्य परामर्शो नेत्याशयेन शङ्कते—**ननूत्तरपदेति** ॥ प्रकृताभिप्रायमेतत् । अप्रधानस्य **न स** इति तत्त्वम् ॥ **संसृष्टेति** । तदेकार्थीभावापन्नेत्यर्थः ॥ यद्यप्युत्तरः पदार्थो यत्रेति बहुव्रीहिणा यथाश्रुतं सुयोजम्; तथापि पूर्वपदार्थेत्यस्य वैयर्थ्यापत्तिः, नियमेन वृत्त्यलाभेन प्रकृतार्थासिद्धिः, वाक्ये तथा सत्त्वेऽपि तदङ्गीकारश्चेति तस्य दुर्वचत्वेन तथा वाच्ये तदन्तर्गतत्वं दुर्वचमत आह—[उ०८प०] **तत इति** । उत्तरपदार्थादित्यर्थः ॥ समुदितादुभयोरेकैवोपस्थितिरिति भावः ॥ तदीयशाब्दबुद्ध्याऽतत्त्वादाह—**मानस्येति** ॥ ननु नियमेन तत्सत्त्वे न मानमत आह—**यद्वेति** ॥ **वाक्येति** । लौकिकं

(उद्द्योतः) वेदाङ्गत्वादिति । तत्त्वं चागमसिद्धम् । अनेन तन्त्रीशब्दादीनामविषयता सूचिता ॥ न च वेदाङ्गत्वाद्वैदिका एव विषयाः स्युः । तत्र तत्र 'भाषायां' 'छन्दसि' इत्याद्युक्त्योभयोरपि विषयत्वात् ॥ ननु चिदानन्दस्वरूपब्रह्मातिरिक्तस्य सर्वस्य लोकपदार्थत्वात् वेदस्यापि लोकान्तर्गतत्वात् भेदेनाभिधानं न युज्यत इत्यत आह—वैदिकानामिति । 'वैदिकानां लौकिकत्वेऽपि' इति पाठः ॥ तेषां त्विति । लौकिकानां यागे कर्मण्येव तत्परिहारः, तेषां तु सर्वत्रेति भावः ॥ भाषाशब्दानामिति । भाषा=प्रयोज्यप्रयोजकवृद्धव्यवहारः, तत्र प्रयुज्यमानानामित्यर्थः । एवञ्च वेदमात्रान्तर्गत-

कर्णेभिर्देवासो गृभ्णामीत्याद्यतिरिक्तपरता लौकिकशब्दस्य, तैस्तद्व्यवहारादर्शनात् । अत एव 'गौरश्वः' इत्यादीनां लौकिकोदाहरणत्वसंगतिः । लोके स्वरानादरात् वेदे तदादराच्च स्वरविशिष्टानां वेदमात्रविषयतामभिप्रेत्य शन्न इत्यादीनां वैदिकोदाहरणत्वसङ्गतिरिति भावः ॥ [भाष्ये—लौकिकास्तावदिति । तावच्छब्दोऽनुक्रमे । पूर्वं लौकिका उदाह्रियन्ते, पश्चाद्वैदिका इत्यर्थः । वैदिकानां प्रधानत्वेऽपि लौकिकानां पूर्वनिर्देशस्तद्वदादरसूचनार्थः ॥] लोके पदानामुदाहरणत्वोक्तौ वेदे वाक्यानामेव तत्त्वोक्तावाशयमाह—तत्रेति । पदान्तरसमभिव्याहारेण स्वरविशेषाच्च वेदे वाक्यानामुदाहर-

त्वार्थमित्युक्तम् । न त्वश्वकर्णादिवच्छुद्धरूढम् । येनाविग्रहत्वं स्यात् ॥ अस्माश्च नियमेन तत्र सत्त्वम् । भाष्ये 'शब्दानाम्' इति तु तत्परामृष्टार्थस्य प्रदर्शनं स्पष्टत्वाय, न स्वतन्त्रम् । अत एवोत्तरे तदनुक्तिः । अत एव 'दशैते राजमातङ्गास्तस्यैवामी तुरङ्गमाः' इत्यादौ न दोषः ॥ यद्वा—अयं दोषस्तदा स्यात् यदि 'केषाम्' इत्येवोक्तं स्यात् । तदा हि शब्दानामित्यस्यानुषङ्गः । स चोक्तरीत्याऽनुपपन्नः । अत्र तु विशेष्यं शब्दानामिति कण्ठत उच्यते तत्तु तत्परमित्यन्यत् ॥ संनिहितत्वं न बुद्धिस्थत्वात् । एवं च तथानिर्दिष्टानामेव तेन परामर्शो न तु तत्र गुणीभूतानाम् । अत एव पुनस्तदुक्तिसाफल्यम् । दण्डिमिश्रावप्येवम् ॥ एतेन—'तस्मिन्नद्रौ' इत्यत्राद्रिपदोक्तिर्व्याख्याता । अन्यथोक्तरीत्या न स्यात् । पूर्वमतेऽप्यत्र न दोषस्तुल्यत्वात् । निर्दयत्वकर्कशत्वादिबोधनेनानाश्रयणीयत्वादिव्यञ्जकतया महाशयत्वाद्यर्थान्तरसंक्रमिततया वा तस्य साफल्याच्च ॥ एवं सर्वत्र बोध्यम् ॥ द्वितीयपक्षे 'दशैते' इत्यादौ सामर्थ्यात्तस्य परामर्शः "आनर्थक्यात्तदङ्गेषु" इति न्यायेन "सविशेषेण हि" इति न्यायेन च ॥ नचैवमपि 'शब्दानां' इत्यस्य पदत्वेन वाक्येत्ययुक्तमिति वाच्यम्, "वाक्ये वाक्यैकदेशः" इति न्यायेनास्यापि तत्त्वव्यवहारात् । साकाङ्क्षपदस्थलविशेषे एकपदेऽपि तत्त्वस्य जयदेवोक्तत्वाच्च ॥ अत एव प्रश्नोत्तरयोः सिद्धान्तरीत्याशयप्रदर्शकोक्तिसंगतिः । तदेतदभिप्रेत्योभयसाधारणमुदाहरति—

[९ पृष्ठे ४ प० प्रदीपे] कैयटे—यथेति ॥

[भा०] लौकिकानामिति । न च वेदाङ्गत्वात् 'वैदिकानाम्' इति प्राग् वक्तव्यम् । तज्ज्ञानमेव हि मुख्यं फलम्, लौकिकज्ञानं त्वानुषङ्गिकम् । न च वैदिकसंप्रदायतस्तत्सिद्धिः, दोषेण तस्याप्यन्यथात्वसंभवात् । शाखाऽऽनन्त्येन तद्वत् प्रातिशाख्यस्य क्वचिदुत्सादात्—इति वाच्यम् । तद्वदादरसूचनाय तथोक्तेः, लौकिकत्वस्य लोकवेदसाधारण-लोकमात्रवृत्त्युभयवृत्तित्वेन व्यापकत्वाच्च । विपरीतं तु न, अग्रिमग्रन्थविरोधापत्तेः । अत एव ब्राह्मणवसिष्ठन्यायप्रवृत्तिसूचनार्थत्वाच्च ॥ संकोचे मानाभावेन लोकशब्दस्य सर्वलोकवृत्तित्वेन तन्त्रयसिद्धत्वेन साधूनामेव ग्रहणं नापभ्रंशानां, प्रतिदेशं तेषां भिन्नत्वात्—इति सूचनार्थत्वाच्चेति भावः ॥

[प्र० १मप०] प्रकरणाभावेऽपि संयोगाद्यन्तर्गतसामर्थ्यसत्त्वाद्विशेषनिश्चय इत्याशयेनाह—कैयटे—सिद्धान्तेति ॥

[प्र० २ यप०] कैयटे—अत एवाह—लोके विदिता इति ॥ प्रसिद्धा इत्यर्थः ॥ वैदिका इत्यनुरोधेन संभवादाह—अथवेति ॥ अत एवाह तत्र—वेदे इति । एतत्कथने तात्पर्यम् । अत एव

पुनः प्रत्ययानुक्तिः ॥

[प्र०६मप०] प्राधान्यमुपपादयति कैयटे—तेषां त्विति । वैदिकानां प्राधान्यं त्वित्यर्थः ॥ बोध्यमित्यग्रे शेषः ॥ वसिष्ठप्राधान्यवैलक्षण्याय—'तु' ॥ यत्नेन-सर्वथा । अन्यथा प्रत्यवायापत्तेः ॥

[प्र०७मप०] युक्त्यन्तरसंभवेन विनिगमनाविरहादाह—अथवेति कैयटे ॥

[उ० १ मप०] चागमेति । 'ब्राह्मणेन' इत्यादीत्यर्थः ॥ ननु नास्येष्टसाधकत्वं लौकिकासंग्राहकत्वादत आह—अनेनेति ॥ आदिनाऽपभ्रंशसंग्रहः । तथा चातिप्रसङ्गनिवारणपूर्वकाभिमतैकदेशसाधकत्वात् सद्धेतुरेवायम् । अत एव 'मत्वा' इत्युक्तमिति भावः ॥ अत एवाशङ्कते—न चेति ॥

[उ०४र्थप०] यत्तु कृष्णः—"प्रयोगचोदनाभावार्थैकत्वमविभागात्" इत्यनेन य एव लौकिकास्त एव वैदिका इति जैमिन्युक्तत्वाद्भेदोक्तिरयुक्तेति । तन्न, सखी कर्णेभिरित्यादीनां मिथो व्यावृत्तत्वात् । तदेतद् ध्वनयन्नाह—ननु चिदेति ॥ पाठ इति । अनेन 'कत्वेन' इति पाठो निरस्तः । 'कानामपि' इति पाठे अपेस्तत्रान्वयः । यथाश्रुते नैष्फल्यं ग्रन्थयोरसामञ्जस्यं चेत्यपि बोध्यम् ॥

[उ०७मप०] तदाह—लौकीति । अर्थबोधायोच्चारणप्रसङ्गे इति शेषः ॥ यद्वा नित्यसाकाङ्क्षत्वात् 'तत्' इत्यत्रैकदेशेऽन्वयः ॥ तस्यानुषङ्गोऽग्रे ॥

[उ० ९मप] ननु तत्र सर्वेषां तत्त्वादेव व्यवच्छेद्यासंभवोऽत आह—एवञ्चेति ॥ तस्योक्तार्थकत्वे चेत्यर्थः ॥ मात्रपदेन गौरश्व इत्यादीनामपि तत्त्वं ध्वनितम् । तेन नाग्रिमग्रन्थविरोधः । तदाह—अत एवेति ॥ नन्वेवं 'शं नः' इत्यादीनामपि तत्त्वमुचितमिति तदुक्तिरयुक्ता । न च 'देवीः, ईले' इत्यादिकं छान्दसं तत्रास्तीति वाच्यम्, तादृशानामेव वाच्यत्वेन तथोक्तेरयुक्तत्वादत आह—लोके इति ॥ मात्रपदेन लोकव्यवच्छेदः ॥

[भा० १० पृ० १ मप०] तत्रेति । तयोर्मध्य इत्यर्थः ॥

[उ०१६ शप०] प्रधानेति । व्याकरणस्य वेदाङ्गत्वात् । एवंचाभ्यर्हितत्वं तेषाम् ॥ तद्वत्-वैदिकवत् ॥ आदरेति । अत एव तत्पदघटितोक्तिसाफल्यम् । अत एव च तद्वत्तेषाम् 'एकः शब्दः' इत्यादिश्रुत्युक्तफलवत्तयाऽभ्यर्हितत्वम् । अन्यथाऽतत्त्वापत्त्या तत्त्वापत्तिरिति भावः ॥ पदानां-पदानामेव ॥ तत्रैवीति । तयोर्मध्य इतीत्यर्थः ॥ लोकेऽपि क्वचित्पदानुपूर्वीनियमसत्त्वादाह—पदान्तरेति ॥ च—आनुपूर्वीनियमसमुच्चायकः । तेन तत्र तस्य सार्वत्रिकत्वं

गत्वोक्तिरित्यपि बोध्यम्॥ लोकवेदसाधारणतया पाणिनीयशब्दानुशासनस्यैवात्राधिकृतत्वम्, न तु शाकटायनादिव्याकरणस्येत्युत्तराशयं परे॥

(जिज्ञासाभाष्यम्)

अथ गौरित्यत्र कः शब्दः?

(प्रदीपः) 'अयं गौः-अयं शुक्लः' इति शब्दार्थयोरभेदेन लोके व्यवहारदर्शनाच्छब्दस्वरूपनिर्द्धारणाय पृच्छति—**अथेति**। 'गौः' इति विज्ञाने प्रतिभासमानेषु वस्तुषु कः शब्द इत्यर्थः॥

(उद्योतः) **अभेदेन लोके इति।** अभेदेनैवेत्यर्थः। शब्दपरत्वाभिप्रायेण 'अस्य गौः' इति प्रयोगाभावादिति भावः। पुरोवर्तिव्यक्तिं पश्यतो वाचकजिज्ञासया कोऽयमिति प्रश्ने 'अयं गौः' 'अयं वर्णः शुक्लः' इत्युत्तरस्थले संनिहितमुद्दिश्य तादात्म्येन शब्दविधेयताप्रतीतेरिति तात्पर्यम्॥ शब्दार्थयोस्तादात्म्यमेव शक्तिः। स्पष्टं चेदं पातञ्जलभाष्ये इति मञ्जूषायामस्माभिर्हर्यादिसंमततया व्युत्पादितम्। अत एव जात्यादिव्यक्त्योरिव **"रामेति द्व्यक्षरं नाम मानभङ्गः पिनाकिनः"** सूचितम्, न तु लौकिके तदभाववत् असार्वत्रिकत्वम्। अपितु बोधसमन्वये इति भावः॥ अस्यापि भेदोक्तिहेतुत्वं बोध्यम्।

अत्रेदं बोध्यम्—गौरित्यादीनां वैदिकत्वेऽपि लोके प्रयुज्यमानतया प्रागुक्तरीत्या वा लौकिकत्वात्तत्त्वोक्तिः॥ स्वरषादीनां(?) तत्त्वेऽपि नोक्तिर्वेदानुपकारकत्वात्। तद्व्युत्पादनं तु प्रासङ्गिकम्॥ अत एव गौरित्यादय एवोदाहृताः॥ नन्वेवमपि घटपटादय एव कुतो नोक्ता इति वाच्यम्, अशोकवनिकान्यायात्। गवाद्यर्थानां मङ्गलत्वेन प्रातर्द्रष्टव्यत्वस्य धर्मशास्त्रे उक्तत्वेन तत्प्रतिपादकत्वाच्छब्दस्यापि मङ्गलत्वमिति आद्युल्लेखाच्च। **पुरुषशब्दश्चा**नादिपुरुषपरः। **शकुनि**शब्दोऽपि चाषादिपर इति दिक्प्रदर्शनम्। तत्रापि दृष्टादृष्टभुक्तिमुक्तिफलकार्थकत्वेनादौ **गौरि**त्युक्तिः। अत एव **'गौः शान्तिरजा शान्तिरश्वः शान्तिः पुरुषः शान्तिर्ब्रह्म शान्तिर्ब्राह्मणः शान्तिः'** इति तैत्तिरीयब्राह्मण उक्तम्॥ नन्वेवमपि गौरित्यादिवत् **शम्** इत्यादीनामपि लौकिकत्वेनैव तत्त्वोक्तिरुचिता, बहूनां तत्त्वादिति वाच्यम्। उक्तोत्तरत्वात्॥ नन्वेवमपि कर्णेभिरित्यादय एवोदाहार्या इति वाच्यम्, प्रायेण लोके प्रयुज्यमाना एव वेदे प्रयुज्यमाना इति सूचनार्थत्वात्॥ अत एव **'देवीरभिष्टये ईळे'** इत्यपि तत्रोक्तम्॥ **देवीरि**ति प्रथमाबहुवचनम्। **अभिष्टये** इत्यत्रेकारलोपः। **ईळे** इत्यत्र ळत्वम्॥ नन्वेवमपि प्रसिद्धऋगादिक्रमेण तत्त्वोक्तिरुचितेति वाच्यम्, तथैव तदुपादेयमित्यत्र मानाभावात्। भाष्यकारस्याथर्वणत्वाच्च। शुद्धच्छान्दसयोस्तत्र सत्त्वाच्च॥ नचान्त्यपक्षद्वयेऽग्रेषु क्रमोक्तौ किं बीजमिति वाच्यम्। आध्वर्यवादेर्ऋत्विजश्च क्रमेण तथोक्तेः॥ यद्वा मङ्गलार्थकसर्वपदघटितत्वेनादौ तदुक्तेः। अग्रे तूक्तैव रीतिः॥

[उ० १९ श्प०] उक्तरीत्या कैयटस्य चिन्त्यत्वात्स्वसिद्धान्तरीत्या आह—**लोकवेदेति**॥ लौकिकवैदिकशब्देत्यर्थः॥ **'अत्र'**इत्यस्यात्रान्वयः॥ यद्वा—**अत्र**-भाष्यवाक्ये। अग्रे **'प्रतिपाद्यते'** इति शेषः। करणस्याधिकरणत्वविवक्षायां सप्तमी॥

भाष्ये—**'गौरित्यत्र'** इत्याद्युपलक्षणं सर्वेषां तस्य च॥

त्यादौ शब्दार्थयोरपि अभेदेन व्यवहारः॥ **अथ गौरिति**-भाष्ये। 'अथ' इत्यस्य 'पृच्छ्यते' इति शेषः॥ किं पृच्छ्यते, तदाह—**गौरित्यत्रेत्यादि॥ कः शब्द इति।** कः शब्दशब्दाभिधेय इति **प्रश्नः॥ प्रतिभासमानेषु**—शब्दजातिव्यक्त्यादिषु॥ नन्वेवं गुणक्रिययोः शब्दत्वाशङ्काऽनुपपन्ना। न हि ते अपि 'गौः'इति शब्दजन्यबोधे भासेते इति चेत्, न। गुणगुणिनोः क्रियाक्रियावतोश्चाभेदात्। शब्दार्थयोश्च तत्त्वात् **'तदभिन्नाभिन्नस्य'** इति न्यायेन तच्छङ्कोपपत्तेः। यथा-परमकारणाभिन्नकार्यकारणकस्य परमकारणेनाप्यभेदः। यद्वा **'गुणसमूहो द्रव्यम्'** इति पक्षे **'तस्य भावः'** इति सूत्रस्थभाष्यसंमते समूहस्य गोशब्दवाच्यत्वेऽवयवभूतगुणादीनामपि तद्वाच्यत्वमिति शङ्का बोध्या। अत्र **'गौरिति विज्ञाने'** इति सामान्योक्त्या तदाकारप्रत्यक्षादिज्ञानेऽपि गुणादीनां सामान्यरूपेण भानम्। अत एव प्रत्यक्षदृष्टेऽपि आम्रफलादौ रसविशेषादिजिज्ञासा, विशेषजिज्ञासायाः सामान्यज्ञानपूर्वकत्वात्-**इत्यन्ये**। निरूपितं चैतन्मञ्जूषायाम्॥

[प्र० १मप०] कैयटे—**इतीति**। इत्यादीत्यर्थः। तेन क्रियादेरपि संग्रहः॥

[प्र०२यप०] कैयटे—**दर्शनादिति**। तथाच संदेह इति भावः॥ अत एवाह तत्र—**निर्धारेति**॥

[प्र०३यप०] प्रागुक्ते **'गौः'** इति स्वरूपे कः शब्दः इति नार्थः, तत्स्वरूपस्य श्रोत्रग्राह्यत्वेन तत्र तत्त्वनिर्णयेन संदेहाभावेन शङ्काऽनुदयात्। किं तु ज्ञानाकारोऽयम्। तथाच तस्यार्थाद्याधारता बोध्या। नचैवमत्रपदानर्थक्यमिति वाच्यम्, तस्य प्रतिभासमानेष्वित्यनेकत्वात्। तस्य च विषयभूतेष्वित्यर्थः। तदेतदभिप्रेत्याह—**गौरितीति** कैयटे। शाब्दे प्रत्यक्षादौ चेत्यर्थः॥

[प्र० ३ यप०] कैयटे—**वस्तुषु**। तेषां मध्ये। तद्विविक्तशब्दत्वभानात्॥

[उ०१मप०] गुणगुण्याद्योरिवाभेदेनापि-इत्यर्थवारणाय एवान्तर्भावेण व्याख्याने बीजमाह—**शब्देति॥ नास्य गौरितीति।** 'घटः शुक्ल इति वद्गौ गौरिति' इत्यन्यादृशस्वरूपस्येवेत्यनुपदं स्फुटीभविष्यति॥ ननु शाब्दज्ञानजनकतया प्रयोगाभावेन कथं प्रत्यक्षभूततथाव्यवहारसाधनम्? किंच 'अयं गौः' इति ज्ञानं ज्ञातशब्दकीयम्, उताज्ञातशब्दकीयम्? आद्ये-'तत्पदवाच्यः सः' इत्यर्थनैषां सिद्धिः। अन्त्ये-अज्ञानेन तस्यैवासंभवादिति चेत्, न; तथा शाब्दज्ञानाभावेन तत्परत्वाभावेन भेदनिरासेनार्थान्तयोर्भेदे सिद्धे ज्ञातशब्दकीयत्वेनैव तत्र तथैवोपपत्तौ तथार्थाङ्गीकारे मानाभाव इत्याशयात्। अत एवात्र द्रढयितुं पृथग् हेत्वन्तरमाह—**पुर इति॥** तदाकारस्तु—अयमित्येव-इत्यादिः॥ **संनिहितमिति।** पिण्डमित्यर्थः। **सांनिध्यं** च देशतः॥ **प्रतीतेरिति**। अन्यथा लोके जायमानायास्तस्या असंगतिः स्पष्टैवेति भावः॥ किंनैवमभावे भेदेन तयोरुक्तिरुचितेति बोध्यम्॥ नन्विदमयुक्तम्, शब्दस्यार्थे त्वस्यङ्गीकारेण तस्या अन्यरूपाया अन्यत्रोक्तत्वेन कथमुक्तार्थे-

(प्रश्नभाष्यम्)

किं यत्तत्सास्नालाङ्गूलककुदखुरविषाण्यर्थरूपम्, स शब्दः?

(प्रदीपः) तान्येव वस्तूनि क्रमेण निर्दिशति—**किं यत्तदिति ।** उद्दिश्यमानप्रतिनिर्दिश्यमानयोरेकत्वमापादयन्ति सर्वनामानि पर्यायेण तल्लिङ्गमुपाददत इति कामचारतः **'स शब्दः'** इति पुंलिङ्गेन निर्देशः ॥

(उद्द्योतः) **'यत्तत्'** इति समुदायो यद्वृत्तार्थे वर्तते, तस्यैव पुनस्तद्वृत्तेन **'सः'**इत्यनेन परामर्शः। यद्वा प्रसिद्धौ। ननु 'यत्'इत्यस्य नपुंसकत्वेन तच्छब्देऽपि नपुंसकलिङ्गमेवोचितमत आह—**उद्दिश्यमानेति ।** सिद्धवत्कीर्तनमुद्देशः। प्रतिपाद्यतया विधेयतया वा कीर्तनं **प्रतिनिर्देशः** । यथा—"शैत्यं हि यत्सा प्रकृतिर्जलस्य" इत्यादौ स्त्रीलिङ्गनिर्देशः ॥ **तल्लिङ्गमिति** ॥ तयोर्लिङ्गमित्यर्थः ॥

(उत्तरभाष्यम्)

नेत्याह, द्रव्यं नाम तत् ॥

(प्रदीपः) **नेत्याहेति ।** भिन्नेन्द्रियग्राह्यत्वान्न **द्रव्यं** शब्द इति प्रतीतम्, अपि तु **द्रव्यं**—इति । यदि च द्रव्यानुशासनं विवक्षितमभविष्यत् 'अथ द्रव्यानुशासनम्' इत्येवावक्ष्यत् ॥

लाभस्ततोऽत आह—**शब्दार्थेति** ॥ यद्यपि वाच्यवाचकभावापरपर्यायं संबन्धान्तरमेव तयोः शक्तिः । तद्ग्राहकं चेतरेतराध्यासमूलकं तादात्म्यं सङ्केतापरपर्यायम्, तथापि तस्यापि पदनिष्ठशक्त्युपकारकत्वाच्छक्तिरिति व्यवहारः । तदभिप्रेत्याह—**तादात्म्यमिति ।** तच्च तद्भिन्नत्वे सति तदभेदेन प्रतीयमानत्वम् । अभेदस्याध्यस्तत्वान्न तयोर्विरोधः । तत्र भेदस्योद्भूतत्वविवक्षया 'अस्यार्थस्यायं वाचकः' **'तस्य वाचकः प्रणवः'** इत्यादौ षष्ठी । अभेदस्योद्भूतत्वविवक्षया तु प्रथमा ॥ अत एवार्थे शब्दधर्मत्वव्यवहारः—'पद्यं श्रुतम्—अथार्थं शृणु' 'पद्यमुक्त्वा अर्थं वदति' इत्यादिः । अत्यन्तभेदेऽश्वपुरुषयोरिव तद्व्यवहाराभावात् । नाप्यत्यन्ताभेदे सः । घटे स्वधर्मत्वव्यवहाराभावात् । कः शब्दः कोऽर्थ इति प्रश्ने घट इत्ययं शब्दो घट इत्ययमर्थः—इत्येकाकारोत्तरदर्शनात्तयोरध्याससिद्धिः । अयमध्यास आदिव्यवहारकृदीश्वरकृत एव । अत एव **'स्थितोऽस्य वाचकस्य वाच्येन सह संबन्धः । संकेतस्तूक्तरूप ईश्वरस्य स्थितमेवाभिसंबन्धमभिनयति यथाऽवस्थितः पितापुत्रयोः संबन्धः संकेतेनावद्योत्यते—अयमस्य पिता, अयमस्य पुत्रः'** इत्यादि पातञ्जलभाष्ये उक्तम् ॥ अत एव च हरिः—

इन्द्रियाणां स्वविषयेष्वनादिर्योग्यता यथा ।
अनादिरर्थैः शब्दानां संबन्धो योग्यता तथा ॥
संबन्धिशब्दे संबन्धो योग्यतां प्रति योग्यता ।
समयाद्योग्यतासंविन्मातापुत्रादियोगवत् ॥
सति प्रत्ययहेतुत्वं संबन्धे उपपद्यते ।
शब्दस्यार्थे यतस्तस्मात्संबन्धोऽस्तीति गम्यते ॥

इति ॥ तदाह—**स्पष्टमिति** ॥ **व्युत्पादितमिति ।** शक्तिवाद इति भावः ॥ उक्तार्थं द्रढयति—**अत एवेति** ॥ तादात्म्यस्यैव शक्तित्वाङ्गीकारादित्यर्थः ॥ **आदिना** गुणक्रियापरिग्रहः ॥ अग्निमादिना **'गर्वभङ्गो भार्गवस्य शौर्यभङ्गश्च वालिनः ॥'** 'हिरण्यपूर्वं कशिपुं प्रचक्षते ॥' **"वृद्धिरादैच्"** **"ओमित्येकाक्षरं ब्रह्म"** इत्यस्य च परिग्रहः ॥

[उ० ९ मप०] पृच्छतीतिकैयटोक्तिसूचितमाह—**अथेत्यस्येति ।** आनन्तर्यार्थकस्येत्यर्थः ॥ **किं पृच्छ्यत इति ।** इति शङ्कायामिति शेषः ॥ **तदिति ।** सामान्यप्रश्नविषयभूतं विशिष्य तथैवाहेत्यर्थः ॥ भाष्ये—इतिस्तु नोक्तः, तस्यार्थपरत्वेन शब्दपरत्वाभावेन तस्यानुपयोगात् । अभेदस्तु तद्विनापि सूपपादः ॥ गौरित्यत्रेत्युक्त्याऽन्यत्रान्यैवेयमाशङ्केति निरासाय प्रकृतसंगतये चाह—**कः शब्द इति ।** तद्घटकशब्द इत्यर्थः । स्फुटत्वाय तस्यार्थपरत्वमिति सूचनाय च **प्रश्न** इत्यस्य पुनरुक्तिः ॥ **'इत्यर्थः'** इति क्वचित्पाठः ॥

[उ० ११ शप०] अत एव व्याचष्टे—**शब्देति ।** अत्रोपस्थापकत्वात्, विशेषगत्वात्, गुणाद्याधारत्वाच्च क्रमोक्तिर्बोध्या ॥

[उ० ११ शप०] **एवम्**—उक्तभाष्यस्योक्तार्थकत्वे ॥ [उ० १२ शप०] **भासेते इति ।** तेन शब्देन तेषां तादात्म्याभावादिति भावः ॥

[उ० १३ शप०] **गुणेति ।** घटः शुक्लः [गौश्चलः] इत्यादिप्रतीतेस्तयोस्तत्त्वसिद्धिः ॥—**श्च तत्त्वात्**—अभेदाच्च । अत्र बीजमुक्तम् ॥ न्यायसत्त्वे मानमाह—**यथेति** ॥ मूलकारणप्रकृत्याद्युपादानकतन्मात्रादिकार्योपादानककार्ये प्रकृत्याद्युपादानकत्वस्यापि व्यवहारे तत्सिद्ध्या यथा तेन, तस्य तेनाभेदप्रतीतिरित्यर्थः ॥ ननु वक्ष्यमाणरीत्या तयोर्विषयतावत्त्वमत आह—[१६ शप०] **यद्वा गुणेति ॥** निरन्तरत्वरूपायुतसिद्धत्ववदवयवविशेषानुगतसामान्यविशेषरूपगुणसमूह इत्यर्थः ॥ [१६ शप०] **पक्ष इति ।** अयुतसिद्धावयवविशेषानुगतः समूहो द्रव्यमिति पतञ्जलिरिति पातञ्जलभाष्योक्तसिद्धान्तपक्ष इत्यर्थः ॥ **तस्य भाव इतीति ।**

तत्र हि * **यस्य गुणस्य भावात्**—* इति वार्तिकव्याख्यावसरे—**किं पुनर्द्रव्यम्, के पुनर्गुणा** इति प्रश्ने **शब्दस्पर्शरूपरसगन्धा गुणाः, ततोऽन्यद् द्रव्यम्** इत्युक्तम् ॥ अत एव 'उक्ते' इति विहायाह—**संमते इति** ॥ इदमुपलक्षणम्—**"स्त्रियाम्"** **"संख्याया अवयवे"** इति सूत्रभाष्ययोरपि ॥ तत्र ह्युक्तम्—**"द्रव्ये च भवतः कः संप्रत्ययः?। गुणसमुदायो द्रव्यम्"** **"कं च प्रत्यवयवो गुणः ॥? ॥ समुदायं प्रति"** इत्युक्तम् ॥ अत्र गुणशब्देनावयवा धर्माश्च ॥ अत एव व्रीहिषु प्रोक्षणजन्यसंस्कारस्यांशत्वावयवत्वादिना व्यवहारः **समन्वयसूत्रे** भामत्याम् ॥ समूहतन्मध्ये निर्मिथो भेदाभेदाभ्युपगमः । अत एव 'मृद् घटः' 'मृदि घटः' इत्यादिसंगतिर्गुणगुण्याद्योरिव । अत एव घटः शुक्लो घटे रूपमित्यादिसंगतिस्तदभिप्रेत्याह—[पृ० १२ उ० १७ शप०] **गुणादीनामिति** ॥ आदिना क्रियाजातिपरिग्रहः ॥ सिद्धान्तमतमाह—[उ० १८ शप०] **अत्रेति** ॥ भाष्यकैयटयोरित्यर्थः ॥ **आदिना**ऽनुमित्यादिसंग्रहः ॥ [१९ शप०] **सामान्येति ।** रूपत्वादिनेत्यर्थः,

(उद्द्योतः) भाष्योक्तहेतुमुपपादयति—**भिन्नेन्द्रियेति** । सामान्यव्यतिरिक्तत्वे सति श्रोत्रेन्द्रियग्राह्यत्वं हि शब्दलक्षणमिति भावः ॥ **यदि च द्रव्येति** । यदि द्रव्यं शब्दशब्दाभिधेयं स्यादित्यर्थः । तथाहि सति द्रव्यादीनां तन्त्रान्तरे निरूपितत्वात्तस्य वैयर्थ्यापत्तिरित्यपि बोध्यम् ॥ तत्र द्रव्यस्य क्रियाद्याश्रयत्वात्पूर्वमुक्तिः । क्रियागुणौ च जात्याश्रयाविति तयोस्ततः पूर्वमुक्तिः । वैशेषिकसिद्धगुणानामपि सङ्ख्यासंयोगविभागादीनां क्रियात्वं ध्वनयितुं गुणात्प्राक् क्रियोक्तिरिति ध्येयम् । **यत्तर्हि शुक्ल** इत्यादिगुणस्य शब्दत्वशङ्कापरे वाक्ये 'इति'शब्देन प्रकारार्थेन सुरभ्यादिभेदभिन्नगन्धादिलिङ्गसंख्यादिरूपगुणसङ्ग्रह इति न न्यूनता ॥ ननु शब्दस्यापि गुणत्वात् 'गुणो नाम सः' इत्युत्तरमसङ्गतम् । तस्य द्रव्यत्वे 'द्रव्यं नाम तत्' इत्युत्तरासंगतिरिति चेत्, न । 'उक्तद्रव्याश्रितो गुणो नाम सः' इत्यर्थात् ॥

(प्रश्नभाष्यम्)

यत्तर्हि तदिङ्गितं चेष्टितं निमिषितम्, स शब्दः ?

(प्रदीपः) अनेनैव न्यायेन गुणक्रियासामान्यानां निराकृतेऽपि शब्दत्वे प्रपञ्चार्थं तत् चोद्यपूर्वकं निराकरोति-**यत्तर्हीति** । गोशब्दार्थे चैषां संभवात् शब्दत्वमाशङ्क्यते । परिहारस्तु पूर्ववत् ॥ तत्रे**ङ्गितम्**=अभिप्रायस्य सूचकः शरीरव्यापारः । **चेष्टितं**=कायपरिस्पन्दः । **निमिषितम्**=अक्षिव्यापारः ॥

(उद्द्योतः) श्रोत्राग्राह्यत्वादेव क्रियादीनां शब्दत्वे निरस्ते किमुत्तरग्रन्थेनेत्यत आह—**अनेनैवेति** ॥ **गोशब्दार्थे चैषां संभवादिति** । अभेदसंभवात्, तेन **'तदभिन्नाभिन्नस्य तदभिन्नत्वं'** इति न्यायेन शब्दत्वाशङ्का तेषामिति भावः ॥ **यद्वा** गोशब्दार्थे गुणसमूहे समूहितया एषां संभवादित्यर्थः ॥ **शरीरव्यापारः**—रोमाञ्चादिः ॥

विशेषस्तु तत्तदिन्द्रियग्राह्य एवेति भावः ॥ [२० शप०] **मानमिति** । इति सूचितमिति शेषः ॥ उक्तं द्रढयति—**अत एवेति** । तेषां तत्र तथा मानादेवेत्यर्थः ॥ [उ० २० शप०] **आदिना** गन्धविशेषादिपरिग्रहः ॥ [पृ०१२उ०२१ शप०] **निरूपीति** । तत्रैवेति भावः ॥

भाष्ये—**सास्नेत्यादिविषाणान्तसमाहारद्वन्द्वप्रकृतिकेनिनाऽवयवी उच्यते** ॥ यत्तु—सास्नेत्यादि द्रव्यान्तरावयवस्याप्युपलक्षणम्, क्रियागुणव्यक्तीनां बह्वीनामग्रे उक्तेः—अत्र द्रव्यान्तरोदाहरणस्यार्थौचित्यात्—इति कृष्णः । तन्न, गौरित्यत्र भासमानविषये शङ्कास्त्वेन तत्र शुक्लादीनां सर्वेषां तत्त्वसंभवे द्रव्यान्तरस्य चातथात्वेन वैलक्षण्यात् ॥ अत एव सामान्यविषये सामान्योक्तावपि तत्र वर्तमानस्यापि द्रव्यत्वादेर्न तत्त्वाशङ्का ॥ भाष्ये—**स शब्द इति** । स शब्दशब्दाभिधेयः किमित्यर्थः ॥

[प्रदीपे १ मप०] कैयटे—**क्रमेणेति** । वक्ष्यमाणबीजक्रमेणेत्यर्थः ॥ **निर्दिशतीति** । तत्र प्रश्नवाक्येन तात्त्विकं तन्मुखादुत्तरमवगन्तुं फलान्तराश्रयं तन्मुखान्निरसितुं च प्रश्नविषयतया तान्येव तथा विशिष्य निर्दिशतीत्यर्थः ॥

[प्र० ३ यम०] यौगपद्यासंभवादाह—**पर्यायेणेति** ॥ कैयटे **इतिर्हेतौ** । न च कामचारे ॥

[उ० १मप०] 'यत्तत्' इति न प्रतीकम्, किंतु व्याख्यानान्तर्गतम् । **समुदायः**-सर्वनामसमुदायः । द्वयोरपि समुदायादिशब्दप्रयोगः ॥ **यद्वृत्तेति** ॥ यदा धृतं निष्पन्नं विभक्त्यन्तमात्रं यदिति तस्यैवार्थे इत्यर्थः ॥ अत एवाह—**तस्यैवेति** ॥ यत्तदोर्नित्यसंबन्धात् ॥ 'सोऽयमाह' 'ते वयं ब्रूमः' इत्याद्यनुरोधेनाह—[उ० २ यप०] **यद्वेति** ॥ **'प्रसिद्धौ तत्'** इति पाठः । तथा च पृथगन्वयः ॥ यद्वा यदित्यनूद्यमानस्य बुद्ध्यारूढत्वाय प्रकृतार्थकतच्छब्दप्रयोगः ॥ अग्रे प्राग्वत् ॥ अत एवाह—**यदित्येति** । नपुंसकलिङ्गार्थाभिधायित्वादिति भावः ॥ [३ यप०] **द्योतितमिति** । तयोरेकविषयत्वादिति भावः । वस्तुतोऽसिद्धत्वेऽपि तत्त्वेन तस्य तत्त्वायाह—[४ थप०] **सिद्धवदिति** ॥ प्रतिपाद्यत्वस्याव्यापकत्वादाह—**विधेयेति** ॥

[उ०] एवं क दृष्टमित्यत्राह—[५ मप०] **यथेति** ॥ **स्त्रीलिङ्गेति** । सेति स्त्रीलिङ्गेत्यर्थः । ननु 'तस्य लिङ्गं' इत्यर्थे परामर्शा-

संभवः **'पर्यायेण'** इत्यस्य वैयर्थ्यमित्यसिद्धिश्चात आह—[उ०६ष्ठप०] **तयोरिति** । प्रक्रान्तयोरित्यर्थः ॥

सिद्धान्ती उत्तरयति—[भाष्ये—] **नेति** ॥ तत्र हेतुमाह—**इत्याहेत्यादि** ॥ यत इत्यादिः । आहेति वर्तमानसामीप्ये लट् । यतः—**'शब्दानुशासनम्'** इत्यवोचत् । न तु 'द्रव्यम्' इत्यर्थः । **नाम** निश्चये प्रसिद्धौ वा ॥ यद्वा—तटस्थः सिद्धान्त्युत्तरमनुवदति—**नेत्याहेति** । इतिर्नञर्थस्य कर्मत्वद्योतकः ॥ तत्र हेतुमाह **स एव—द्रव्यमिति** ॥ यत इत्यादिः ॥ एवमग्रे सर्वत्र ॥

[दक्षिणभागे प्र०]—**यत** इत्यस्यार्थमाह—कैयटे—**भिन्नेन्द्रियेति** ॥ शब्दग्राहकश्रोत्रान्यचक्षुर्ग्राह्यत्वादित्यर्थः ॥ तत्र **द्रव्यं** तत्त्वेनाभिमतम् ॥ नामपदार्थमाह—[२ यप०] **प्रतीतमिति** ॥ तर्हि केन धर्मेण तत्प्रसिद्धमित्यत्राह—**अपि त्विति** । गुणाश्रयत्वात् तत्समूहत्वाद्वेत्यर्थः ॥

ननु शब्दशब्दस्य कर्मघञन्तत्वेनार्थपरत्वमेवास्तु, अत आह [१४ पृ. प्र. २ यप०] तत्र—**यदि चेति** ॥

[उ० १मप०] तदभिप्रेत्याह—**भाष्योक्तेति** ॥

[उ० १मप०] हेत्वसिद्धिं परिहरन्हेतौ हेतुमाह—[१ मप०] **सामान्येति** ॥ अनेन शब्दनिष्ठसामान्येऽतिप्रसङ्गो वारितः ॥ विशेष्यदलेन द्रव्यादिनिरासः ॥ **हि**—यतः ॥ **शब्देति** । शब्दसामान्येत्यर्थः ॥ एतेन—अर्थबोधायानुच्चार्यमाणत्वान्न तत्त्वम्—इति रत्नोक्तमपास्तम् । अर्थबोधायानुच्चार्यमाणेऽनुकरणे व्याप्तेः ॥

[उ०] अत एव यथाश्रुतमनुपपन्नं व्याचष्टे—[३ यप०] **यदि द्रव्यमिति** । स्यादित्यनेन 'अभविष्यत्' इत्यत्र कालाविवक्षा सूचिता । एवं च 'अवक्ष्यत्' इत्यस्यापि 'वदेत्' इत्यर्थो बोध्यः ॥ हेतुहेतुमद्भावरूपलिङ्निमित्तसत्त्वात् 'भूते च' इति लृङ् इति केचित् ॥ **इत्यर्थ इति** । इति मूलभूतार्थे इत्यर्थः ॥ ननु विनिगमनाविरहात्तथोक्तिः । न च स्फुटप्रतीतिभवनं तथा, कर्मघञन्तानुशासनसत्त्वेन तस्यावश्यकत्वेऽपि तत्त्वात् । न च लोकप्रसिद्धिस्तथा, लोकप्रसिद्धितः शास्त्रप्रसिद्धेः प्राबल्येन तस्या अविशिष्टत्वात्, अत आह—**तथाहीति** ॥ अन्यार्थत्वस्यावश्यकत्वेन वैपरीत्यं नेति सूचनायाह—[४ थप०] **दीनामिति** ॥ यन्निर्वेष्विसम

(उत्तरभाष्यम्)

नेत्याह, क्रिया नाम सा ॥

(प्रश्नभाष्यम्)

यत्तर्हि तत् शुक्लो नीलः कपिलः कपोत इति, स शब्दः ?

(प्रदीपः) **शुक्लो नील इति** । द्रव्यस्य प्रागुपन्यासाद्गुणमात्राभिधायिनोऽत्र शुक्लादयो द्रष्टव्याः ॥

(उत्तरभाष्यम्)

नेत्याह, गुणो नाम सः ॥

(प्रश्नभाष्यम्)

यत्तर्हि तत् भिन्नेष्वभिन्नं छिन्नेष्वच्छिन्नं सामान्यभूतं, स शब्दः ?

(प्रदीपः) **भिन्नेष्वभिन्नमिति** । अनेन सामान्यस्य 'एकत्वं' कथ्यते । 'छिन्नेष्वच्छिन्नं' इत्यनेन तु 'नित्यत्वम्' ॥ **सामान्यभूतमिति** । सत्ताख्यं महासामान्यं गोत्वादेः सामान्यविशेषस्योपमानं निर्दिष्टम् । सामान्यमिव—**सामान्यभूतम्** । भूतशब्द उपमार्थे, यथा—पितृभूत इति ॥

(उद्द्योतः) **एकत्वमिति** । अनेकसमवेतत्वस्याप्युपलक्षणम् । नित्यत्वेन संयोगनिरासः । एकत्वेन प्रत्यभिज्ञाप्रत्यक्षरूपं प्रमाणं दर्शितम् ॥ भूतशब्दप्रयोगानुपपत्तिं परिहरति—**सत्ताख्यमिति** । एवं हि 'वृक्षवदाम्रः' इत्याद्यापत्तेः, सामान्यश्रुतेः सर्वसामान्यविषयत्वेन प्रवृत्तायाः संकोचे कारणाभावाच्च, उपमाकथनस्य प्रकृतेऽनुपयोगाच्च, अध्याहारे गौरवाच्च—नेदं युक्तम् । किं तु स्वरूपवाची सः । वृद्धिसंज्ञासूत्रस्थभाष्यप्रयोगस्य **'प्रमाणभूतः'** इत्यस्य स्वयं करिष्यमाणव्याख्यानरीत्याऽस्यापि व्याख्यानसंभवात् ॥ 'पितृभूतः' इत्यत्रापि 'अन्यत्रान्यशब्दप्रयोगः सादृश्यपरः' इति सादृश्यप्रतीतिः, न त्वस्य सादृश्यवाचकत्वे मानमस्तीति दिक् ॥

(उत्तरभाष्यम्)

नेत्याह, आकृतिर्नाम सा ॥

(उद्द्योतः) भाष्ये—**आकृतिः**—जातिः संस्थानं च, आक्रियते—व्यवच्छिद्यते स्वाश्रयोऽनयेति व्युत्पत्तेरिति भावः ॥ शङ्कापरभाष्ये **'सामान्यभूतम्'** इत्यस्य तद्व्यञ्जकं चेत्यप्यर्थो बोध्यः ॥ जातिमात्रपरत्वे **'जात्याकृतिव्यक्तयः पदार्थः'** इति गौतमसूत्रेण तस्यापि पदार्थत्वबोधनात् प्रत्यक्षादौ तद्ग्रानाच्च तस्य शब्दत्वाशङ्कातत्समाधानाभावेन न्यूनता स्यात् ॥ **'सिद्धे शब्दार्थ—'** इति वार्तिकव्याख्याने

वक्तव्यमतमाह—**तत्रेति** ॥ तत्र भासमानानां मध्ये इत्यर्थः ॥ नन्वेवमपि शुक्लादिगुणस्य चिरतरसमयस्थायितया सर्वसंमतप्रत्यक्षतया च पूर्वमुक्तिर्युक्ता न क्रियायाः, तद्विलक्षणत्वादत आह—[६ छप०] **वैशेषिकेति** । तन्मतेत्यर्थः ॥ प्रसङ्गादत्रैवाह—[८ मप०] **यत्तर्हीति** ॥ [९ मप०] **प्रकारेति** । सादृश्येत्यर्थः ॥

अन्यथा तदानर्थक्यं स्पष्टमेवेति भावः ॥ 'यत्तत्' इति नपुंसकनिर्देशेन चेत्यपि बोध्यम् ॥ **आदिना** स्पर्शादिपरिग्रहः ॥ अग्र **आदिना** शक्तिरूपकारकपरिग्रहः ॥ तत एवात्रैवाह—[१० मप०] **नन्विति** ॥ [१·२ शप०] **इति तदर्थादिति** । इत्युत्तरार्थादित्यर्थः ॥ **'इत्यर्थात्'** इति पाठेऽप्येवम् ॥ अनेन **'द्रव्यं नाम तत्'** इत्यस्य 'वक्ष्यमाणगुणाश्रयो द्रव्यं नाम तत्' इत्यर्थः सूचितः । लिङ्गसंख्याद्यन्वयि द्रव्यमित्यादि तु स्वशास्त्रव्यवहारोपयोगीति बोध्यम् ॥

[२ यप्र० १ मप०] तत्रान्तरस्यक्रमेणाह—कैयटे—**गुणक्रियेति** ॥ **निराकृतेऽपि**—तत्प्रायेऽपि ॥ **प्रपञ्चार्थम्**—प्रसिद्धान्तरावगमाय ॥ अत एव सर्वत्र नामपदोक्तिः ॥ तत्—तेषां शब्दत्वम् ॥ **यत्तर्हीतीति** । यदि द्रव्यं न शब्दः, तर्हीङ्गितादेस्तदन्यत्वात्तत्त्वमस्तीत्यर्थः । **तर्हि** यत्तत्—इङ्गितादि स किं शब्द इति योजना बोध्या ॥ एवमग्रेऽपि सर्वत्र ॥

[२ यप्र०] कैयटे—[४ धप०] **तत्रेङ्गीति** । त्रयाणां मध्य इत्यर्थः ॥

[२ यउ० १ मप०] **निरस्ते**—निरस्तप्राये ॥

[द० भागे उ० २ यप०] कैयटेन शङ्काबीजं व्याख्यायामुक्तमेव प्रदर्श्यत इति ध्वनयन्नाह—**अभेदेति** ॥ नन्वेवमपि शब्देनाह—**यद्वेति** ॥ **एषां**—क्रियादीनाम् ॥ **संभवादिति** । तथा च गोशब्दे तत्समूहाभेदोऽपि सिद्ध एव तदन्यावयविनोऽप्रानुपलम्भादिति बोध्यम् ॥

[उ० ६ छप०] कायपरिस्पन्दस्य वक्ष्यमाणत्वादाह—**रोमाञ्चादिरिति** ॥ अनेन येनेङ्ग्यते भावः प्राणिनां तत्—इङ्गितम् इति व्युत्पत्तिः सूचिता ॥

[१ मभा० १ मप०] भाष्ये—**क्रियेति** ॥ प्राधान्येन कृदन्तधातुवाच्यत्वादिति भावः ॥

[२ यभा० १ मप०] **कपोतः**—चित्रः । **'इति'**शब्दस्य प्रयोजनं तूक्तम् ॥

[३यभा० १ मप०] **गुणो नामेति** । द्रव्यकर्मेतरसामान्यवत्त्वाच्छब्दस्य गुणत्वेऽपि रूपादीनां गुणत्वयोगेनैव शब्दसाधर्म्यम्, न तु शब्दत्वयोगेनेति न दोषः ॥

[१ मप्र० २ यप०] कैयटे—**तुरुत्ववैलक्षण्ये** ॥

[द० भागे उ०१ मप०] न्यूनतां परिहरति—**अनेकेति** । तथा च 'नित्यमेकमनेकानुगतं सामान्यम्' इति तल्लक्षणं सूचितम् ॥ तत्राद्यकृत्यमाह—[२ यप०] **नित्येति** ॥ एकमिति स्वरूपकथनपरं न विशेषनिवृत्त्यर्थम् । तेषां प्रतिस्वं भिन्नत्वात् । तद्ध्वनयन्नाह—**एकत्वेनेति** ॥ **प्रमाणमिति** । सामान्यसद्भावे इति शेषः ॥

[उ० ४ धप०] **एवंहीत्यस्य** नेदं युक्तमित्यत्रान्वयः ॥ सामान्यविशेषयोरुपमानोपमेयभावाङ्गीकारे हीति तदर्थः ॥ **सर्वेति** । सामान्यविशेषरूपेत्यर्थः ॥ [६ छप०] **अध्याहारे इति** ॥ गोत्वादिरूपसामान्यविशेषवाचिशब्दाध्याहार इत्यर्थः ॥ नन्वेवं झटिति श्रुत्यनुपपत्तिरत आह—**किंत्विति** । अर्थान्तरपरतया तस्योपपत्तिरिति भावः ॥ ननु स्वरूपवाचित्वे न मानमत आह—[७ मप०] **वृद्धीति** । अत एव चोक्तिः, स चान्ते योज्यः ॥ सामान्यशब्दस्तद्वृत्तिधर्मपरः । **'भूतं'** इति भूप्राप्तावित्यस्य 'आधृषाद्वा' इति णिजभावे रूपम् । प्राप्तमिति तदर्थ इति भावः ॥

भाष्ये तस्या अपि पदार्थत्वं नित्यत्वञ्च कैयटो वक्ष्यति । '**तदभिन्नाभिन्नस्य तदभिन्नत्वम्**' इति न्यायस्तु यत्र स्वाभिन्नद्वारकः स्वस्वरूपानुगमस्तद्विषयः । यथा—**परमकारणकार्योपादानके** परमकारणाभेदः । अत एव सुखदुःखयोर्नैक्यम् । नापि कुण्डलकटकयोस्तत्, कुण्डलारम्भकस्वर्णावयवानुगमस्य कटकेऽभावात् एवं गुणसमूहस्यानुद्भूतावयवभेदस्य वाच्यत्वेऽपि समूहिनां तद्रूपेणावाच्यत्वान्न तेषां शब्दत्वाशङ्केति भावः ॥

(प्रश्नोपसंहारभाष्यम्)

कस्तर्हि शब्दः ?

(प्रदीपः) द्रव्यादिषु निरस्तेषु पृच्छति—**कस्तर्हीति** ॥

(उद्द्योतः) पृच्छतीति । प्रश्नविषयविशेषान्तराभावात् सामान्यरूपेण पृच्छतीत्यर्थः ॥

(समाधानभाष्यम्)

येनोच्चारितेन सास्नालाङ्गूलककुदखुरविषाणिनां संप्रत्ययो भवति, स शब्दः ॥

(प्रदीपः) उत्तरमाह—**येनोच्चारितेनेति** । वैयाकरणा वर्णव्यतिरिक्तस्य पदस्य वाक्यस्य वा वाचकत्वमिच्छन्ति । वर्णानां प्रत्येकं वाचकत्वे द्वितीयादिवर्णोच्चारणानर्थक्यप्रसङ्गात् । आनर्थक्ये तु प्रत्येक**मुत्पत्तिपक्षे** यौगपद्येनोत्पत्त्यभावात्, **अभिव्यक्तिपक्षे** तु क्रमेणैवाभिव्यक्त्या समुदायाभावात् । एकस्मृत्युपारूढानां वाचकत्वे 'सरः' 'रसः' इत्यादावर्थप्रतिपत्त्यविशेषप्रसङ्गात्तद्व्यतिरिक्तः **स्फोटो** नादाभिव्यङ्ग्यो वाचको विस्तरेण वाक्यपदीये व्यवस्थापितः । **उच्चारितेन**—प्रकाशितेनेत्यर्थः ॥

(उद्द्योतः) भाष्ये—**उच्चारितेनेति** । शारीरमारुताभिहतकण्ठादिस्थानैरवयवद्वाराऽभिव्यक्तेन येनेत्यर्थः ।

ननु पितृभूत इत्यस्यानुरोधेन तथैव कुतो नात आह— [८ मप०] **पितृभूत इति** ॥ **इति**—इति न्यायेन ॥ [१०म०] **दिगिति** । तदर्थस्तु तत्रापि स्वरूपपरत्वेनैव निर्वाहः । **किंच** 'प्रमाणभूतः' इत्यादाविव निर्वाहस्तत्र । **किंच** सामान्यं च तद्भूतं चेति कर्मधारयः । भूतशब्दः परमार्थवाची सामान्यस्यापोहरूपतां प्रतिक्षेप्तुमुपात्तः, तस्याघटादिव्यावृत्त्यात्मनो घटोऽयं घटोऽयमित्याद्यनुगताकारप्रत्ययविधिमुखप्रवृत्तशब्दविषयत्वायोगेनाप्रामाणिकत्वादिति बोध्यमिति ॥

यत्तु—आकृतिर्जातिरत्र, वक्ष्यमाणव्युत्पत्तेः । अवयवसंयोगरूपाकृतेर्गुणत्वात् 'गुणो नाम' इत्यनेन गतार्थत्वादिति कृष्णः, तदसदिति ध्वनयन् तथैव वाच्य आकृति पदस्वारस्यादित्याह—[२ म० ३० १ भप०] **संस्थानं चेति** । रूपक्रियादिविशिष्टमवयवसंस्थानं चेत्यर्थः । तादृशतदाकार इति यावत् । अत एव गां लिखेत्यादौ लेखनकर्मत्वोपपत्तिः । '**पिष्टकमय्यो गावः**' इत्यत्राकृतेः पदार्थत्वमावश्यकम् ॥ एवं व्याख्याने बीजान्तरमाह—[४ धंप०]—**जातीति** ॥ **यस्तु पेति** । अत्र "तुशब्दो विशेषणार्थः ॥ **किं विशिष्यते ? अप्रधानोपसर्जनभावस्यानियमेन पदार्थत्वम् । यदा भेदविवक्षा विशेषगतिश्च तदा व्यक्तिः पदार्थोऽङ्गं जात्याकृती** । यथा गौस्तिष्ठति गौर्गच्छतीति । तयोः स्थानादीनामसंभवात् सा पदार्थः । **यदा पुनरभेदो विवक्षितः सामान्यगतिश्च तदा जातिः पदार्थः, इतरे विशेषणे** । यथा "गौर्न पदा स्प्रष्टव्यः" इति तद्वार्तिक(तद्भाष्य)कारः ॥ **तस्यापि**—संस्थानस्यापि ॥ नन्वेवमपि तस्य पदार्थत्वं न भाष्यादिसंमतमिति न साऽत आह—**सिद्धे इति** ॥ **पदार्थत्वमिति** । उक्तमिति शेषः ॥ नन्वेवमपि व्यक्तिवत्तस्यानित्यत्वेन 'भिन्नेषु—' इति लक्षणानाक्रान्तत्वाच्छङ्काया एवाभावेन कथमुत्तरे तथाऽत आह—**नित्येति** । तत्रैवेति भावः ॥ ननु तदभिन्नेति न्यायेन शङ्कापक्षे एवं निराकरणे न्यायस्य निर्विषयतापत्तिरत आह—**तदभिन्नेति** ॥ पेक्षेण शङ्कायामेवं निराकरणाशयमाह—**एवमिति** ॥ तद्वदित्यर्थः ॥ **समूहिनाम्**—अवयवानाम् ॥ ननु 'यः शब्द्यते स शब्दो नेत्याह अर्थरूपं तत्' इत्येकेन वाक्येनेष्टसिद्धेरनेकवाक्यवैयर्थ्यमिति चेत् । न, मन्दबुद्धीनां स्पष्टप्रतिपत्त्यर्थं तथोक्तेः ॥

[१ मउ० १ मप०] पूर्वप्रश्नतोऽत्र विशेषमाह—**प्रश्नेति** ॥ नच कर्मव्युत्पत्त्या शब्दत्वनिरासेऽपि भावव्युत्पत्तिरूपप्रकारान्तरं संभवतीति वाच्यम्, तत्र क्रियारूपमेवोत्तरमित्याशयात् । अन्यस्य प्रकारस्य निर्वक्तुमशक्यत्वात् । तत्र भासमानशब्दस्य तत्त्वस्येष्टत्वाच्चेति भावः ॥

[२ यभाष्ये १ मप०] **उच्चारितेने**तिविशेषणेन गृहीतसंकेतस्य स्वरूपसतो बोधकत्वं निरस्तम् ॥ प्रकाशितस्यैव तत्त्वात् ॥

[वामे २ यप्र० १ मप०] कैयटे—**उत्तरमिति** । सिद्धान्तीत्यादिः । शब्दपदं करणघञन्तमिति भावः ॥

[२ यप्र० २ यप०] पदस्यापि कल्पितत्वादाह—**कैयटे—वाक्यस्य चेति** ॥

[२ यप्र० ५ मप०] कैयटे—**तुरप्यर्थे** ॥

[२ यप्र० ६ छप०] कैयटे—**आदिना**—'जरा, राज' 'नदी, दीन' इत्यादिपरिग्रहः । तत्र—**प्रसङ्गादिति** । वर्णानामुभयत्राविशेषादिति भावः ॥

[२ यउ० २ यप०]—**स्थानैः** । '**साक्षादवयवद्वारा वाऽभि—**' इति पाठः ॥ तत्राखण्डस्थले साक्षात् । सखण्डस्थले—अवयवद्वारेति बोध्यम् ॥

[२ यउ० ३ यप०] न्यूनतां परिहरति—**अत्रेति** । अनेन प्रागुक्तरीतिः सूचिता । बहुवचनं तु व्यक्त्यभिप्रायमिति भावः । यत्तु—संप्रत्ययः स्मरणम् 'एकसंबन्धि—' न्यायेन—इति रत्नकृत् । तन्न, पदार्थोपस्थितेः स्मृतित्वस्य मञ्जूषायां निराकृतत्वात् । अत आह—**ज्ञानमिति** ॥

[२ यउ० ५ मप०] **समूहाभीति** । अनुद्भूतावयवभेदकसमूहेत्यर्थः ॥ **समूहेति** । 'तद्वदत्र' इत्यादिः ॥ **स्थिरस्य**—चिरकालस्थायिनः ॥

[२ यउ०] पदाधिक्यपरिहारायाह—[८ मप०] **द्वितीयमनूद्येति** । आद्यदोषमित्यर्थः ॥ तत्राद्यमाह—**प्रत्येकमानर्थक्ये स्विति** । वर्णानां प्रत्येकं वाचकत्वे द्वितीयादिवर्णानामानर्थक्ये स्वित्यर्थः ॥ शेषपूरणमाह—[९ मप०] **समुदेति** । **तत्तु**—तदपि ॥ [१०मप०] **तत्र**—समुदायस्य वाचकत्वे ॥ **नयेति** । मतेत्यर्थः ॥

अत्र विषाणान्तैरवयवैर्गुणादयोऽप्युपलक्ष्यन्ते ॥ **संप्रत्ययः**—ज्ञानम् ॥

ननु प्रत्यायकशब्दस्य वर्णसमूहरूपतया 'येन' इत्येकवचनमयुक्तम् । न च 'वनम्' इतिवत् समूहाभिप्रायं तत्, समूहस्य स्थिरस्य निरूपयितुमशक्यत्वादत आह—**वैयाकरणा इति** ॥ वर्णव्यतिरिक्तपदानभ्युपगमे एकैकस्य वर्णस्य वाचकत्वं, समुदायस्य वा, नाद्य इत्याह—**वर्णानां प्रत्येकमिति** ॥ द्वितीयमनूद्य दूषयति—**आनर्थक्ये तु प्रत्येकमिति** । प्रत्येकमानर्थक्ये तु समुदायस्य वाचकत्वमुपेयम्, तत्तु न युक्तम्—इति शेषः । यतस्तत्र नयद्वयम्—उत्पद्यमानसमुदायस्य—अभिव्यज्यमानसमुदायस्य वा वाचकत्वमिति । तत्राद्यं दूषयति—**उत्पत्तिपक्षे इति** । 'उत्पत्त्यभावात्' इत्यस्य 'समुदायाभावात्' इत्यनेनान्वयः ॥ द्वितीयं दूषयति—**अभिव्यक्तीति** । उत्पन्नाभिव्यक्तेर्ध्वस्तत्वादित्यर्थः ॥ ननु पक्षद्वयेऽपि पूर्वपूर्ववर्णानुभवजसंस्कारसहकृतान्त्यवर्णानुभवहेतुकैकस्मृत्युपारूढानां वाचकत्वमस्त्वत आह—**एकस्मृतीति** ॥ ननु तस्य नित्यत्वे सर्वदाऽर्थप्रतीतिप्रसङ्गोऽत आह—**नादेति** । नादः—वर्णः ॥ ननु येन क्रमेणानुभूता वर्णास्तेनैव क्रमेणैकस्मृत्युपारूढानां वाचकत्वेन नार्थप्रतीत्यविशेषप्रसङ्गः, अन्यथा त्वयाऽपि वर्णानां स्फोटव्यञ्जकत्वाभ्युपगमात् कथं पूर्वोक्तदोषान्निस्तारस्तवापीत्यत आह—**विस्तरेणेति** । इदं—'एकं पदम्' 'एकं वाक्यम्' इति प्रत्ययः स्फोटसत्त्वे तदैक्ये च प्रमाणम् । अनुभवक्रमेणैव स्मरणमित्यर्थे दृढप्रमाणाभावाच्च । क्रमेणानुभूतानां व्युत्क्रमेणापि स्मरणदर्शनात् । **मम** तु यथा पटे नानारञ्जकद्रव्याहितनानावर्णोपरागः क्रमेण, तथा एकस्मिन्नेव तस्मिन्नुच्चारणक्रमेण क्रमवानेव तत्तद्वर्णस्वरूपानुरागः, स च स्थिरः, तस्य च मनसा ग्रहणमिति न दोषः ॥ तत्र 'येन' इत्येकवचनेन 'विषाणिनाम्' इति बहुवचनेन चानेकोच्चारणविषयगौरित्यस्यैकत्वं सूचितम् । एवं च तेनैव दृष्टान्तेन घटपटादिबोधकसाधारण्येन वाचकस्यैकत्वं सूचितम् । भेदप्रत्ययस्त्वौपाधिक इत्याद्यसत्कृतमञ्जूषायां शक्तिवादे द्रष्टव्यम् ॥ नन्वेवं तस्य ताल्वोष्ठपुटव्यापारविषयत्वाभावात् 'उच्चारितेन' इत्ययुक्तमत आह—**प्रकाशितेनेति** । अभिव्यञ्जकैरिति शेषः ॥

उत्पद्यात । षष्ठीसमासः ॥ एवमग्रेऽपि ॥

[२ य उ०] क्रमेणैवेत्यत्र हेतुमाह—[१३ शप०] **उत्पन्नेति** ॥ [१५ शप०] **मस्त्वेति** । एवं च पक्षद्वयमप्यदुष्टमिति भावः ॥

[२ य उ०] ध्वनिवारणायाह—[१७ शप०] **वर्ण इति** ॥ वर्णसत्त्वपक्षे साक्षाद् ध्वनिव्यङ्ग्यत्वस्य तत्रासंभवाद्विति भावः ॥ ननु येन क्रमेणानुभवास्तेनैव क्रमेण स्मरणानीति दोषनिवारणमत्र कुर्वचम्, स्मृतेरनैकत्वादत आह—**ननु येनेति** । नन्विति स्फोटाभावशङ्कायाम् ॥ [१९ शप०] **पूर्वोक्तेति** । अर्थप्रतीत्यविशेषप्रसङ्गरूपादित्यर्थः । तदुक्तम्—

> **'यस्यानवयवः स्फोटो व्यज्यते वर्णबुद्धिभिः ।**
> **सोऽपि पर्यनुयोगेन न केनापि विमुच्यते ॥'** इति ॥

[२१ शप०] **प्रत्यय इति** । न चायं वर्णगोचरः, तेषामनेकमिति प्रतीत्या नानात्ववत्त्वात् । न चायं भ्रान्तः, बाधाभावादित्याद्यन्यत्र बोध्यम् ॥ युक्त्यन्तरेण तं संसाध्य कैयटोक्तदोषमपि प्रतिपादयन् तां खण्डयितुं हेतुमाह—**अनुभवेति** । तदुक्तम्—

> **'नानुभूतिक्रमाद्वर्णाः क्रमिकाः स्मृतिगोचराः ।**
> **गोचरोऽनुभवो न स्यात्तत्क्रमस्ते कुतः पुनः ॥'** इति ॥

अत्र हेतौ हेतुमाह—[२२ शप०] **क्रमेणेति** । प्रपूर्वदिनानुभूतं विहाय पूर्वदिनानुभूतस्मृतिस्थल इति भावः ॥ नन्वेवं वर्णानां स्फोटव्यञ्जकत्ववादिनस्तव कथं निर्वाहोऽत आह—[२३ शप०] **मम त्विति** ॥ **तस्मिन्**-स्फोटे ॥ **उच्चारणक्रमेणेति** । न तु भवदुक्तरीत्येति भावः ॥ ननु तस्यापि क्षणिकत्वे प्रागुक्तदोष एवात आह—[२५ शप०] **स चेति** । स्फोटश्चेत्यर्थः ॥ पारमार्थिकत्वादाह—**स्थिर इति** ॥ तस्य श्रोत्राग्राह्यत्वादाह—**तस्य चेति** । इदमन्यत्र स्पष्टम् ॥ न चैवं प्रतिज्ञाविरोधः, लिप्यादिवत्तदुपायत्वात् । व्यञ्जकानुशासनद्वारा व्यङ्ग्यस्यैवानुशासनाच्च ॥ ननु **'येन'** इत्येकवचनस्य स्फोटाभिप्रायकत्वेऽपि प्रश्नवाक्यवदेकवचनमेव **विषाणिनामि**त्यत्र युक्तमत आह—[२५ शप०] **अत्रेति** । भाष्य इत्यर्थः ॥ **तत्र** इति पाठेऽप्येवम् ॥ **नेकोच्चारणेति** । व्यक्तिभेदात्कर्तृभेदाच्चेत्यर्थः ॥ अधिकमाह—**एवं चेति** । तस्य तत्त्वसूचने चेत्यर्थः ॥

[१८ पृ० उ० २८ प०] **वाचकेति** । स्फोटस्येत्यर्थः ॥ **सूचितमिति** । सुष्ठूचितमित्यर्थः । **समुचितमिति** पाठस्तु सुगम एव ॥ कथं तर्हि घटपटादिशब्दानां भेदप्रतीतिरत आह—**भेदेति** । उपाधिर्वर्णरूपः ॥

[उ० २९ प०] **एवं**—तदतिरिक्तत्वे ॥ तेषां बहुत्वात्तैरेव व्यञ्जितादर्थप्रतीतेरिष्टत्वाच्चाह—[३० शप०] **अमीति** ॥ एकेनैवाभिव्यक्त्येष्टसिद्धेरन्यानर्थक्यम्, निरवयवस्य सर्वात्मनाऽभिव्यक्तत्वेऽप्येकेनान्येषां स्फुटतराभिव्यक्त्यर्थत्वात्तरतमेन्द्रियसंबन्धेन स्फुटस्फुटतरक्रमेणान्त्यसंबन्धे स्फुटतमा व्यक्तिर्न प्राक् संबन्धे यथा तथा गकारादिध्वनिभिस्तरतमादिभावेन स्फोटाभिव्यक्तिस्वीकार इति तदनन्तरमेवार्थधीर्न ततः प्राक् । एवमर्थाभिव्यक्तिस्तु न, स्फुटत्वस्य संनिकर्षभेदेन प्रत्यक्षज्ञाननियतत्वात्स्फोटज्ञानस्य च प्रत्यक्षत्वात् । अर्थो यथाभिहितो नाभिव्यक्तः, संदिग्धश्चेत्याभिहित इत्याद्यन्यत्र द्रष्टव्यम् ॥

[द० १ मभा०] ननूक्तलक्षणलक्षितस्य लौकिकबहिर्भूतत्वात्कथमनुशासनम्, तदनुशासने च **'लौकिकानां'** इत्याद्युपक्रमविरोधापत्तिः । यद्यपीदं कौस्तुभाद्युक्तरीत्या सुसमाधानम्, तथापि **'लौकिकानां'** इत्यादिमेदेनोक्तेर्बहुवचनान्तेनोक्तेस्तथोदाहृतत्वाच्च तथाऽनभिमतत्वस्य व्यवहारदशायां भगवदिष्टत्वेन तदस्वारस्यादुपक्रमविरोधश्च । **किं च** यस्मादर्थाप्रतीतिः कारणवशात्तस्य शब्दत्वानापत्तिः । **किंच** वर्णेभ्योऽर्थाप्रतीतिरेवेति वर्णानां शब्दत्वव्यवहारः सार्वजनीनो विरुध्येत । **किंच** प्रागुक्तशब्दसामान्यलक्षणानाक्रान्तत्वं तस्य, मनसा तस्य ग्रहणात्—अत आह—[१ मप०] **भाष्ये-अथवेति** ॥ प्रतीतः पदार्थ इति कर्मधारय एव । स्वार्थे कन् । तस्य च तद्बोधके **लक्षणा** । ध्वनय एव वर्णाः । अन्यत्रोक्तरीत्या अनुभवेन च वर्णस्थले ध्वनीनामावश्यकत्वेन तैरेव स्फोटत्वेनाभिमताभिव्यक्तिसंभवे तयोरन्तरा वर्णाङ्गीकारे गौरवात् । दूरगतकोलाहलश्रवणे घत्वादीनां श्रूयमाणध्वनिगतानामेव दूरत्वदोषेणानभिव्यक्तिसंभवाच्च ॥ एवं चैकैकवर्णोऽपि सहकारिवर्णान्तरसंबन्धादनेकपदरूप इति सोऽपि तच्छक्तिरिति गकारौका-

(समाधानान्तरभाष्यम्)

अथवा-प्रतीतपदार्थको लोके ध्वनिः शब्द इत्युच्यते । तद्यथा-शब्दं कुरु, मा शब्दं कार्षीः, शब्दकार्ययं माणवकः, इति ध्वनिं कुर्वन्नेवमुच्यते । तस्मात् ध्वनिः शब्दः ॥

(प्रदीपः) **अथवेति** । अन्यत्र ध्वनिस्फोटयोर्भेदस्य व्यवस्थापितत्वादिहाभेदेन व्यवहारेऽपि न दोषः, द्रव्यादयो न शब्दवाच्या इत्यत्र तात्पर्यात् ॥ **ध्वनिं कुर्वन्निति** । विधिप्रतिषेधयोरप्रवृत्तविषयत्वात्कथमस्य त्रिभिः संबन्धः ? उच्यते— शब्दं कुर्वन्नपि 'शब्दं कुरु' इत्युच्यते विरामाशङ्कायां तन्निवृत्तये । तथाऽनभिमतशब्दश्रवणोद्वेजितेनोच्यते-मा शब्दं कार्षीरिति ॥

(उद्योतः) भाष्ये—**अथवा प्रतीतपदार्थक इति** । लोके व्यवहर्तृषु पदार्थबोधकत्वेन प्रसिद्धः श्रोत्रेन्द्रियग्राह्यत्वाद्वर्णरूपध्वनिसमूह एव शब्द इत्यर्थः । तस्यार्थबोधकताऽप्यविचारितरमणीयस्यैव लोके सिद्धा, तादृशस्यैव शास्त्रेणान्वाख्यानमिति तात्पर्यम् । तदाह— **अन्यत्रेति** । संग्रहादौ, तपरसूत्रे भाष्ये चेत्यर्थः । ध्वनिपदेनात्र वैखरी, स्फोटपदेनाभिव्यक्तकत्वादिको मध्यमावस्थ आन्तरः शब्द उच्यते ॥ **कथमस्येति** । 'कुर्वन्'शत्रस्य वर्तमानार्थत्वादित्यर्थः ॥

(शास्त्रप्रयोजनाधिकरणम्)

(प्रयोजनजिज्ञासाभाष्यम्)

कानि पुनः शब्दानुशासनस्य प्रयोजनानि ?

र्विसर्जनीया गौर्वाचका इति लोकस्याविचारितरमणीये तत्समूहे वाचकत्वग्रहः । अखण्डोऽपि स्फोटो गकाराद्यवस्थाभ्यो भिन्नोऽभिन्नश्च चरमावस्थया विसर्जनीयादिरूपया पदादिरूपेण व्यज्यत इति वर्णेषु तत्त्वव्यवहारोपपत्तिर्लोकस्येति बोध्यम् ॥

[१ प्रमा० २ यप०] भाष्ये '**इत्युच्यते**' इत्यनेन सिद्धान्त्यनभिमतत्वमस्य सूचितम् ॥

[१ प्रमा०] प्रतीतत्वमेव विशदयति—भाष्ये [२ यप०] **तद्यथेति** ॥ ध्वनिं कुर्वन्नित्येवमुच्यत इति संबन्धः ॥ यद्वा— ध्वनिं कुर्वन्नेवमुच्यते । एवंपदार्थ एव—**इतीत्यन्तः** ॥

[१ प्रमा० ४ थंप०] तथा चायं हानोपादानोपेक्षात्मा त्रिविधो व्यवहार इत्यन्वयव्यतिरेकाभ्यां तस्य श्रावणत्ववाचकत्वयोरवसायः । तद्ध्वनयन् तदनुसारेणोपसंहरति—भाष्ये—**तस्मादिति** । लोकव्यवहारादित्यर्थः ॥ ध्वनिः—उक्तरूपः ॥

[१ प्रप्र० ४ थंप०] **अप्रवृत्तेति**—कैयटे । अप्रवृत्तस्य प्रेरणानिषेधयोरसंभवादिति भावः ॥ एकेन संबन्धसंभवेऽपि समुदायेन तदसंभवादाह—**त्रिभिरिति** ॥ [६ छप०] तत्र **तथाऽनभीति** । एवमुदासीनेन वस्तुस्थितिः कथ्यते—**शब्दकारीति**-**इति** बोध्यम् ॥

[१ प्र उ० १ प्र प०] तदभिप्रेत्याह—**लोक इति** ॥ तदर्थमाह—[२ यप०] **व्यवेति** । अस्य बोधे प्रतीतो वाऽन्वय इत्याह—**पदार्थेति** । अत एव वक्ष्यति—**तस्येति** ॥ प्रतीतपदार्थमाह—**श्रोत्रेति** ॥ वर्णरूपत्वं ध्वनौ तत्समूहे च बोध्यम् ॥ ननूक्तरीत्या तस्य नार्थबोधकत्वमत आह—[३ यप०] **तस्येति** ॥ नन्वेवं कथं तस्य तत्त्वोक्तिरत आह—**शास्त्रेति** ॥ अविचारितरमणीयस्यैवेत्यर्थः ॥ परं त्विदं तद्वृत्त्यैवेति बोध्यम् ॥ एतदर्थमेवेयमुक्तिरिति भावः ॥ [५ मप०] **आदिना** ह्रयोदिपरिग्रहः ॥

[१ प्र उ० ५ मप०] **नात्र**-कैयटे ॥ इदं चाग्रे सर्वं स्फुटीभविष्यति ॥

[२ य उद्यो०] ननु शब्दानुशासनपदेनात्र व्याकरणं तद्वाच्यं दुर्ग्रहम्, तस्यानधीतस्य रक्षादिप्रयोजनासंभवात् । तस्याक्रियात्मकत्वेन नित्यत्वकाम्यत्वासंभवेन कैयटासांगत्याच्च । अत एव **आदि**—असंगत्यापत्तेश्च । अतो लाक्षणिकमर्थमाह—[१ मप०] **शब्देति** ॥ [२ यप०] **तदाहेति** । लाक्षणिकमर्थं हृदि कृत्वाऽऽहेत्यर्थः ॥ शब्दज्ञानफलकत्वादेव नेदं साक्षात्प्रयोजनप्रश्नपरमित्याह—**शब्देति** ॥ [३ यप०]—**ध्ययनेति** । व्याकरणेत्यादिः ॥ **परिहारः**—स एव ॥ **अपिना** तस्य समुच्चयः ॥

आद्ये नित्यत्वम् । द्वितीये काम्यत्वम् ॥ [४ थंप०] **किंचिदिति** । अनेन 'भाष्यस्थपुनःशब्दो विशेषे' इति सूचितम् ॥ प्रयोजनप्रश्नार्थस्तु न, फलस्य प्रागुक्तत्वात् । तद्द्वितीये तदवगतेश्च ॥ उत्तरानुरोधेनाह—[४ थंप०] **प्रयोजेति** । 'बाहुलकात्कर्तर्युत्पन्नः प्रयोजनशब्दः प्रयोजकपरः' इति कृष्णकौस्तुभाद्युक्त्यसांगत्यध्वननायाह—**करणेति** । प्रयुज्यते प्रवर्त्यतेऽनेनेतीत्यर्थः ॥

[उ० ५ मप०] **अपिना** फलपरसमुच्चयः । तत्राद्यः पुंलिङ्गोऽन्त्यो नपुंसकलिङ्ग इति बोध्यम् । अत एव वक्ष्यति—[७ मप०] **नपुंसकेति** ॥ **तेन**—आद्यपरत्वेन ॥ [६ छप०] **किंचिदिति** । प्रत्यवायपरिहारातिरिक्तमपि किंचित्प्रवर्तकमस्ति उत तद्रूपमेवास्तीत्यर्थः ॥ नन्वेवं प्रश्नोत्तरयोः कथं वचनभेदोऽत आह—[७ मप०] **तत्रैकेति** । एकशेषे इत्यर्थः ॥ अत्रेदं बोध्यम्—पुनःशब्दः पश्चादर्थकोऽपि सुयोजः, तादृशैतदध्ययनस्य पुनः पश्चात् शब्दज्ञानानन्तरम् अन्यानि वा प्रयोजनानि किं दृष्टानि किं वाऽदृष्टानि पुरुषार्थसाधनभूतानीति । पुरुषार्थसाधनभूतानीति तु तत्पक्षेऽप्यावश्यकमितीति ॥ यद्यपि प्रतिज्ञावाक्येनैवानुबन्धचतुष्टयं सूचितम्, तथापि साधुशब्दज्ञानस्य सुखदुःखाभावान्यतरारूपत्वेन साक्षादपुरुषार्थत्वमिति तत्साधनत्वमेवास्य दृष्टद्वारकं वाच्यम् । तत्रादृष्टं द्वारं प्रत्यवायपरिहाररूपं स्वयमुपेक्ष्य दृष्टद्वारा तद्बोधकतानयोः स्फुटैव ॥

[२ यमा० १ मप०] ननु साधुरक्षा नाध्ययनस्य प्रयोजनमत आह—भाष्ये—**रक्षार्थमिति** । **अर्थशब्दः** प्रयोजनवाची ॥ स्वरूपसताऽनेन वेदरक्षा दुष्कराऽत आह—**अध्येतव्येति** ॥ अनेनैतच्छास्त्रस्येयं संज्ञेति दर्शितम् ॥ एवमग्रेऽपि ॥ अत एव प्रश्ने '**शब्दानुशासनस्य**' इति तथा व्याख्यातम् । अन्यथाव्याख्यातॄणां त्वेतदर्थविरोधोऽपि स्पष्ट एवेति बोध्यम् ॥ ननु पाठमात्रेणाधीतेनाप्यनेन कथं वेदरक्षाऽत आह—**लोपेति** ॥ प्रकृतिप्रत्ययविभागादेरप्युपलक्षणमिदम् ॥ **हि**—हेतौ ॥ तथा च न केवलं तथाध्ययनं किंतु वाक्यार्थावगतिपर्यन्तमपीत्यनुपदमेव स्फुटीभविष्यति ॥

[१ प्रप्रदी०] कैयटे—**अस्येति** । एतदध्ययनस्येत्यर्थः ॥ एवमुपलक्षणम्—अस्यानुज्ञापकं मानमागमरूपमस्तीत्याद्यपि बोध्यम् ॥ यद्वा—अस्याध्ययनस्य पारम्पर्येणाविशिष्टाध्ययनविधानेनाङ्गाध्ययनविधेर्लाभात्तद्द्वारा धर्मादिसाधनतामित्यर्थः कैयटस्य तत्पक्षे बोध्यः ॥

(प्रदीपः) **कानि पुनरिति** । किं संध्योपासनादिवद्व्याकरणाध्ययनं नित्यं कर्म–अथ काम्यमिति **प्रश्नः** ॥

(उद्द्योतः) भाष्ये–कानि पुनः शब्दानुशासनस्येति । शब्दज्ञानफलकव्याकरणाध्ययनस्येत्यर्थः । तदाह–**किं सन्ध्येति** । शब्दज्ञानद्वारा–अध्ययनस्य तदज्ञानप्राप्तप्रत्यवायपरिहारः फलम्, उत तदतिरिक्तमपि किंचिदिति **प्रश्नाशय** इत्यर्थः ॥ **प्रयोजनशब्दः** करणव्युत्पत्त्या प्रयोजकपरोऽपि । तेन व्याकरणाध्ययनस्य प्रयोजकं किञ्चिदस्ति, न वा-इत्यपि प्रश्नाशयो बोध्यः । अत एवोत्तरे आगमपदोपादानम् । **'नपुंसकमनपुंसकेन–'** इत्येकशेषः । तत्रैकवद्भावस्य वैकल्पिकत्वात्प्रश्ने बहुवचनम्, उत्तरे एकवचनं बोध्यम् ॥

(प्रयोजनभाष्यम्)

रक्षोहागमलघ्वसंदेहाः प्रयोजनम् ॥

(रक्षापदार्थनिरूपणभाष्यम्)

रक्षार्थं वेदानामध्येयं व्याकरणम् । लोपागमवर्णविकारज्ञो हि सम्यग्वेदान्परिपालयिष्यतीति ॥

(प्रदीपः) पारम्पर्येण पुरुषार्थसाधनतामस्याह—**रक्षेति** । लोके लोपाद्यदृष्टं वेदे दृष्ट्वा भ्राम्येदवैयाकरणः, वैयाकरणस्तु न भ्रमति, वेदार्थं चाध्यवस्यति । तत्र **लोपागमयोरुदाहरणं**—देवा अदुह्रेति । दुहेर्लङो झस्यादादेशे कृते **'लोपस्त आत्मनेपदेषु'** इति तलोपः, **'बहुलं छन्दसि'** इति रुटि सति रूपमेतत् । **वर्णविकारो** यथा—**उद्ग्राभं च निग्राभं चेति** । **'हृग्रहोर्भश्छन्दसि'** **'हस्येति वक्तव्यम्'** इति भकारः । **'उदि ग्रहः'** इत्यत्र **'उद्ग्राभनिग्राभौ च छन्दसि स्रुगुद्यमननिपातनयोः'** इति वचनादुन्निपूर्वाद्ग्रहेर्घञ् ॥

(उद्द्योतः) पुरुषार्थः=धर्मो मोक्षश्च ॥ ननु शिष्याचार्यसंबन्ध एव महान् वेदरक्षाहेतुः, किं व्याकरणेनेत्यत आह—**लोके इति** ॥ **भ्राम्येदिति** । भ्रमेण पाठान्तरं कल्पयेदित्यर्थः । न चाचार्यवचनाद् भ्रमनिवृत्तिः, भ्रंशशङ्कया तेष्वविश्वासात् ॥ वेदार्थावगमद्वाराऽपि व्याकरणं पुरुषार्थसाधनमित्याह—**वेदार्थं चेति** । एवञ्च वेदार्थज्ञानपूर्वकं श्रुतत्वन्मश्रैस्तद्विहितकर्मानुष्ठानेन स्वर्गसुखम्, उपनिषदर्थज्ञानेन वक्ष्यमाणरीत्या वा मोक्षश्च पुरुषार्थौ व्याकरणाध्ययनस्य फलमिति भावः ॥ **विकार इति** ॥ लोपस्तु न विकार इति पृथग्गणितः । भावरूप एव चादेशोऽत्र विकारः ॥ **हृग्रहोर्भ इति** । इदं च 'गृभ्णामि' इत्याद्यर्थमावश्यकम् । एतेन **'उद्ग्राभनिग्राभौ** चेत्यनेनैव भस्यापि सिद्धत्वादेतदुपन्यासश्चिन्त्यः' इति परास्तम् । अन्यार्थमावश्यकेन तेनैव भस्य सिद्धौ तदंशे निपातनाश्रयणवैयर्थ्यात् ॥ निपूर्वाद्ग्रहेर्घञ्विधायकाभावादाह—**उद्ग्राभनिग्राभौ चेति** ॥

[प्र० २ यप०] कैयटे—**वेदे इति** ॥ 'त्मना देवेभिः' इत्यादावित्यर्थः ॥

[प्रदीपे] **सम्यगित्यादेरर्थमाह** कैयटे—[२ यप०]—**वैवेति** । **न भ्राम्येति** । सिद्धं पाठं त्यक्त्वा पाठान्तरं न कल्पयेत् । तल्लक्षणदर्शित्वादनायासेन यथावस्थितपाठस्थापनं कर्तुं प्रभवेदिति यावत् ॥ एवं च भवति वेदरक्षा फलमप्रधानम्, प्रधानं तु धर्मादिरूपपुरुषार्थ एव ॥

[प्र० ३ यप०] कैयटे—**तत्र–लोपादीनां** मध्ये ॥ यद्यपि **'त्मना व्योमन्'** इति लोपमात्रोदाहरणम्, **'ब्राह्मणासः'** इत्यागममात्रस्य तथापि लाघवादाह—**लोपागमेति** ॥

[प्रदीपे] यद्यपि वर्णविकारमात्रस्य जभार गृभ्णामि इत्युदाहरणम्, तथापि विशेषं प्रतिपादयितुं छान्दसप्रत्ययसंवलितस्य उदाहरणमाह—कैयटे [६ छप०] **उद्ग्राभं चेति** ॥

[प्रदी० ९ मप०] **निपातनयोरिति** वार्तिके पाठः ॥ एवं च निग्राभमिति छन्दस्येव, उद्ग्राभमित्यत्रार्थांश एव निपातनम्, अन्यांशेऽनुवादः ॥ यद्यपि संनिवेशविशेषयुक्ताः पात्रविशेषाः स्रुचः, तथापि स्रुगुपलक्षितोरेव ग्रहणम् । **'उद्ग्राभं चेति स्रुचमुद्यच्छति निग्राभं चेति उपभृतं नियच्छति'** इति वचनात् ॥

[उद्द्यो०] श्रुतकाम्यत्वनिरासाय कामो न पुरुषार्थ इत्याह—[१ मप०] **धर्म इति** । विनिगमनाविरहाद्धर्मस्य तत्साधनत्वात्स्वेऽपि स्वतोऽतत्त्वाद्वक्ष्यमाणरीत्या चाह—**मोक्षश्चेति** ॥ एतेन 'अर्थकामसाधकत्वमपि संभवतीति तत्त्यागोऽनुचितः' इत्यपास्तम् । तयोः स्वतोऽतत्त्वात्, परमपुरुषार्थसाधकत्वसंभवे तत्कथनानौचित्याच्च । विशिष्टाध्ययनविधेश्च तथैव तत्त्वाच्च ॥

[उ० २ यप०] **किं व्येति** । तदध्ययनेन किमित्यर्थः ॥ **लोक इतीति** । आत्मनेत्यादावित्यर्थः ॥

[उद्द्यो०] ननु तस्य भ्रमे इष्टापत्तिरत आह—[उ० ३ यप०] **भ्रमेणेति** । एवं च तस्य न व्याकरणसाम्यमिति भावः ॥ [४ धप०] **भ्रंशेति** । अपभ्रंशेत्यर्थः ॥ न च पदैकलक्षणं निर्विस्थापकम्, तस्य व्याकरणलक्ष्यत्वात्स्वलक्ष्याव्याप्त्यये निर्विवादत्वात् । न च प्रातिशाख्यादितत्तन्निवृत्तिः, तेषामनन्तासु शाखासु क्वचित्क्वचिदुत्पादादर्शनात् । न च तद्विरोधात्स्यात्सन्तबाधः, शाखान्तरपरतयाऽत्यन्तबाधकत्वस्याकल्पनात् ॥ एतेन—

> "वेदरक्षाऽपि नैतस्मात्तेऽप्येतत्परम्पराम् ।
> संप्रदायोऽनुवृत्तश्चेद्वेदस्तेनैव रक्ष्यते ॥
> प्रातिशाख्यविरोधे च बाध्यते व्याक्रिया वरम्"

इति भट्टोक्तमपास्तम् ॥ न च मीमांसयाऽर्थावगमः, जर्भरीत्यादावत्यन्ताप्रसिद्धे तस्या अव्यापारादिति दिक् ॥

[उद्द्यो०] तदेतत्सूचयन्नाह—[उ० ४ धप०] **वेदार्थेति** । वेदार्थावगमपूर्वकवेदरक्षणद्वारेत्यर्थः ॥ **अपिरुक्तरीत्या** श्रुतरक्षाद्वारसमुच्चायकः ॥ [५ मप०] **व्याकेति** । तदध्ययनमित्यर्थः ॥ 'पारम्पर्येण'इति कैयटतात्पर्यमाह—**एवं चेति** । अस्य वेदार्थनिश्चयकत्वे चेत्यर्थः ॥ [६ छप०] **श्रुतेति** । अनेन वेदार्थावगमस्य रक्षाऽपेक्षान्तरं प्रयोजनं सूचितम् ॥ अत एवाध्ययनमस्य न पाठमात्रं किन्तु वाक्यार्थावगतिपर्यन्तम् । अन्यथा स्वरज्ञानाद्वेदरक्षाऽपि न स्यात् । सति तु तस्मिन्ज्ञानार्थान्स्वरज्ञानसंशयानां निवृत्त्या सा । अत एव **'श्रेयश्च'** इति तत्रोक्तम् ॥ उपनिषदर्थज्ञानस्यान्यथाऽपि संभवात्. **'यतोवाच'** इति श्रुत्या

(ऊहपदार्थनिरूपणभाष्यम्)

ऊहः खल्वपि । न सर्वैर्लिङ्गैर्न च सर्वाभिर्विभक्तिभिर्वेदे मन्त्रा निगदिताः । ते चावश्यं यज्ञगतेन यथाऽर्थं विपरिणमयितव्याः । तान्नावैयाकरणः शक्नोति यथाऽर्थं विपरिणमयितुम् । तस्मादध्येयं व्याकरणम् ॥

(प्रदीपः) **ऊहः खल्वपीति** । इह यस्मिन्यागे इतिकर्तव्यतोपदिष्टा यागान्तरेणोपजीव्यते सा **प्रकृतिः** । येन चोपजीव्यते सा **विकृतिः** । **'प्रकृतिवद्विकृतिः कर्तव्या'** इति मीमांसकैर्व्यवस्थापिते न्याये प्रकृतिप्रत्ययादीनामूहं वैयाकरणः सम्यग्विजानाति । तत्राग्नेर्मन्त्रोऽस्ति—**अग्नये त्वा जुष्टं निर्वपामि**—इति, तत्र **'सौर्यं चरुं निर्वपेद् ब्रह्मवर्चसकामः'** इति सौर्यचरौ मन्त्र ऊह्यते—**सूर्याय त्वा जुष्टं निर्वपामि**—इति । विस्तरेण भर्तृहरिणा प्रदर्शित ऊहः ॥

(उद्द्योतः) भाष्ये—**'खल्वपि'** इति निपातसमुदायो निश्चयार्थः । 'ऊहः खल्वपि' इत्यस्य प्रयोजनमिति शेषः । ननु यत्र प्रकरणे ये मन्त्राः पठितास्तत्र तेषां तथैव प्रयोग इष्ट इति नोहेन प्रयोजनमित्याशङ्क्य प्रकृतावूहाभावेऽपि विकृतावूह इति दर्शयितुं प्रकृतिशब्दार्थमाह—**इहेति** । **यस्मिन्**—आग्नेयादौ । **यागान्तरेण**—सौर्यादिना । प्रकृतिविकृत्यवगमश्च द्विदेवत्यस्यैकदेवत्यस्यादिसाम्येन बोध्यः ॥ अन्यत्र पठितमन्त्राणां कथमन्यत्र गमनमत आह—**प्रकृतिवदिति** । यथा—सोपकारा प्रकृतिरनुष्ठीयते, तथा विकृतेरपीति तदर्थः । तदनेनोपकारातिदेशे तत्पृष्ठभावेन पदार्था अप्यतिदिश्यन्ते, इतिकर्तव्यताया भावनायाः साकाङ्क्षत्वात् । एतन्मूलकमेव **'प्रकृतिवत्'** इति—इति मीमांसकसरणिः ॥ पदार्थान्तर्गताश्च मन्त्राः । तत्र अग्निसंबन्धिनिर्वापप्रकाशमन्त्रस्याग्निपदस्य सूर्यसंबन्धिनिर्वापप्रकाशनासमर्थत्वात्तदपहाय तत्स्थाने 'सूर्याय'इत्यूह्यमित्याह—**तत्राग्नेरिति** ॥ **मन्त्र ऊह्यत इति** । यद्यप्यूहे न मन्त्रत्वम्, तथाप्येकदेशस्योहेऽपि अनेकपदसमुदाये मन्त्रत्वप्रत्यभिज्ञानात्तद्घटिते समुदाये मन्त्रत्वव्यवहारः, कर्मणः साङ्गत्वं चेति बोध्यम् । सोऽयं प्रकृत्यूहः । अन्येऽप्यूह्याः । ऊहस्य हि आर्त्विज्यलाभेन द्रव्यप्राप्तिद्वारा ऐहिकसुखसिद्धिः फलमिति बोध्यम् । भाष्ये—लिङ्गपदं च प्रकृत्यादेरुपलक्षणम् ॥ **यथायथमिति** । अर्थप्रकाशनसामर्थ्यानतिलङ्घनेनेत्यर्थः ॥

(आगमपदार्थनिरूपणभाष्यम्)

आगमः खल्वपि । "ब्राह्मणेन निष्कारणो धर्मः षडङ्गो वेदोऽध्येयो ज्ञेयः" इति ॥ प्रधानं च षट्स्वङ्गेषु व्याकरणम् । प्रधाने कृतो यत्नः फलवान्भवति ॥

(प्रदीपः) **आगम इति** । आगमः प्रयोजनः प्रवर्तकी नित्यकर्मतां व्याकरणाध्ययनस्य दर्शयति । 'प्रयोजन'शब्देन च फलं-प्रयोजकश्चोच्यते ॥ **निष्कारण इति** । दृष्टं कारणमन-

---

ब्राह्मणस्तथा शब्दापोध्यत्वस्योक्तत्वादाह— [७ मप०] **वक्ष्येति** ॥ गौणप्रयोजनकथनावसरे इति भावः ॥

[उद्द्योते] ननु लोपस्यापि वर्णविकारत्वात्पृथगुक्तिरयुक्ता अत आह—[उ० ८ मप०] **लोपस्त्विति** । अत्र तत्त्वेनाभिमत इत्यर्थः ॥ तदेवाह—[९ मप०] **भावेति** । चो हेतौ ॥ एवं चान्यत्र तथा सत्त्वेऽपि न क्षतिरिति बोध्यम् ॥

[उ० १० मप०] **आदिना** 'जभार' इत्यस्य परिग्रहः ॥ [११ शप०] **अपिना** चस्समुच्चयः ॥ [१२ शप०] **नैव मस्य सिद्धाविति** पाठः ॥ **वैयर्थ्यादिति** । अन्यथा **'सख्यशिश्वी'** इत्यनेन ङीप इयेकारलोपस्यापि निपातनादेव सिद्धौ **'सख्येति च'** इत्यत्रस्यस्य **'इकारस्येति परे लोपः'** इत्यंशस्य **'अतिसखेरागच्छति अतिसखेः स्वम् इत्युदाहरणम्'** इति भाष्यस्यासंगतिः स्यादिति भावः ॥ तत्र **'उदि ग्रहः'** इत्यनेनोत्पूर्वाद् ग्रहेर्लोकेऽपि घञः सिद्धत्वादाह—**निपूर्वादिति** ॥ एवं च निग्राभमित्यस्यासिद्धिरिति भावः ॥

[भाष्ये] **लिङ्गैः**—सर्वलिङ्गबोधकपदैः ॥ **विभक्तिभिः**—सर्वविभक्त्यन्तपदैः । 'युक्ताः' इति शेषः । **मन्त्रो निगदिता** इत्यत्रान्वयः ॥ व्रीह्यादिद्रव्यसंबन्धिनोऽवघातादेर्नीवारादिसंबन्धलक्षणसंस्कारोहे यद्यपि व्याकरणाध्ययनस्य नोपयोगः, तथापि मन्त्रोहे उपयोग इति सूचयन्नाह—**मन्त्रा इति** ॥ प्राकृतकरणस्वरूपप्रयुक्तत्वे मन्त्राणां विकृतौ तत्स्वरूपाभावात्तदप्राप्त्या नोहः फलम्, किंतु अपूर्वप्रयुक्तत्वे मन्त्राणामिति सिद्धान्तादिष्टत्वावपि तस्य सत्त्वेन मन्त्रप्राप्त्या तदूहः फलमिति सूचनायाह—**ते चावश्यमिति** । **यथायथमिति** पाठे प्रकृतिमुख्यार्थामुख्यार्थादिभेदेनोहः । न तु यथाकथंचिदित्यर्थः ॥ **विपरिणेति** ॥ तत्तल्लिङ्गादिबोधनक्षमपदयुक्ततया पाठ्या इत्यर्थः ॥ तेषां तथा पठनमेवोहपदार्थः ॥ ननूह्यमानपदानां वेदादेवोपलब्धत्वात् प्रयोगो भविष्यति किं व्याकरणेनात आह—**तान्नावैयेति** । यथा प्रत्यक्षश्रुतिमूलमपि स्मृतिप्रणयनं धर्मावगमे प्रमाणम्, एवं व्याकरणमप्यूहे इति भावः ॥ उपसंहरति—**तस्मादिति** ॥ यस्मात्तेन तद्दुष्करं तस्मात्तदर्थमेतदध्येयमित्यर्थः ॥

[प्रदीपे] भाष्ये लिङ्गविभक्तिग्रहणं प्रकृत्यादेरुपलक्षणमित्यभिप्रेत्याह—**कैयटे** [४ धंप०] **प्रकृतीति** ॥ **आदिना** लिङ्गपरिग्रहः ॥ **सम्यक्**—यथोचितम् ॥

[प्र० ५ मप०] **कैयटे—तत्र विकृतौ** ॥ तत्र—[६ छप०] **इति सौर्ये इति** । इति विहितसूर्यदेवताकचरुद्रव्यकयाग इत्यर्थः ॥

[उ० १ मप०] क्रमप्राप्तमूहं कथयतीत्याह—**उद्द्योते—भाष्ये ऊहः खल्वपीत्यस्येति** ॥ ननु रक्षार्थमित्यापस्संबद्धपदव्यवायेन विच्छिन्नत्वादनुषक्तो न । तदुक्तम्—**'अनन्तरेण संबन्धः स्यात् परस्याप्यनन्तरे'** इति, अत आह—**शेष इति** ॥ यद्यपि खलुशब्द एव निश्चयार्थः, अपिरन्यसमुच्चायक इति सुवचम्, तथापि परिगणनादेव समुच्चयः सिद्ध इत्याशयेनाह—**खल्वपीति निपातेति** ॥ [३ यप०] **ये मन्त्रा इति** । यादृशा इतियावत् ॥

[उ० ४ धंप०] **प्रकृतीति** । इदं च लक्षणं संभवाभिप्रायं बोध्यम् । वस्तुतस्तु यत्राङ्गजातं पूर्णमुपदिष्टं सा प्रकृतिः, यत्र

पेक्ष्येत्यर्थः ॥ **प्रधानं चेति।** पदपदार्थावगमस्य व्याकरणनिमित्तत्वात्तन्मूलत्वाद्वाक्यवाक्यार्थावसायस्येति भावः ॥

(उद्द्योतः) ननु वक्ष्यमाणागमस्य न व्याकरणफलत्वमत आह—**प्रवर्तक इति ॥ नित्यकर्मत्वमिति।** एतेन नित्यकाम्यता व्याकरणाध्ययनस्येत्युक्तम्। **नित्यत्वं** चाध्येयपेयपदार्थविशेषणीभूताध्ययनज्ञानयोर्बोध्यम्। अत्र ब्राह्मणेनेत्युक्तेरन्यस्यैवमध्ययन काम्यमेवेति सूचयतीति कश्चित् ॥ **निष्कारण इति।** कारणशब्दः फलपरः ॥ ननु नित्यत्वेऽपि प्रत्यवायपरिहाररूपं फलमस्त्येवेत्यत आह—**इष्टमिति।** अध्ययनादिनिष्ठं कारणानपेक्षत्वं विषये आरोप्य 'निष्कारणो वेदः' इति प्रयोगः। आगमपदेन **श्रुतिः।** श्रुता-

नोपदिष्टं सा **विकृतिरिति** सार्वत्रिकं लक्षणं बोध्यम् ॥ नन्वेवमपि कथं प्रकृतिविकृतिभावावगमोऽत आह—[६ शप०] **प्रकृतीति।** तद्भावावगमश्चेत्यर्थः ॥ **आदिना** ओपधिद्रव्यकत्वादिपरिग्रहः ॥ प्रकृतितुल्या या विकृतिः सा कर्तव्येत्यर्थे—विकृतौ प्रकृतितुल्यत्वस्य बाधितत्वात्तत्कथनानुपयोगादतिदेशवैयर्थ्यापाताच, तद्विदं कार्येत्वर्थे—तत्तत्त्वस्यान्यथा दुर्वचत्वात्प्रयायार्थमाह—[८ शप०] **यथेति ॥** प्रकृतावङ्गानि येनोपकारेण तामुपकुर्वन्ति यथा, विकृतावपि तेन तेनोपकारेणैव तानि तामुपकुर्वन्तीत्यर्थः ॥ वैदिकस्य विधेरुपकारापेक्षायां करणस्य वैदिकत्वात्तथाविधानामेवाङ्गानामपेक्षितत्वात्तेषामेव प्रकृतौ श्रुतसामर्थ्यत्वात्तान्यौपदेशिकसंबन्धाभावेऽप्यतिदेशेन प्राप्यन्ते। तदाह—[९ शप०] **तदनेनोपेति ॥** अत एवोपकारस्यासंभवे सामान्येनातिदेशेऽपि केषांचिन्निवृत्तिः साकल्येनैकदेशेन वा ॥ [९ शप०] **इति केति ॥** निरितिकर्तव्यताकस्य कर्मणोऽभावाच सर्वत्राख्याते भावनाया विधेयत्वात्तस्याश्चांशत्रययोगित्वात् 'किं-केन-कथम्' इति साध्यसाधनेतिकर्तव्यताकाङ्क्षानियतत्वादितिकर्तव्यतां विना साध्यसाधनयोरन्वयायोगात्तदावश्यकत्वमिति भावः ॥ नन्वरत्नूक्तरीत्या पदार्थातिदेशः, मन्त्रातिदेशस्तु दुर्घटोऽत आह—[११ शप०] **पदार्थान्तर्गतेति ॥**

[उद्द्योते] एकदेशस्यानुपकारान्नानुवृत्तिरित्यत्र कैयटेन सम्यक् तस्योपपादनाय दत्तमुदाहरणमुपपादयंस्तमवतारयति—[११ शप०] **तत्रेति ॥** प्रकृतावित्यर्थः ॥ तेन मन्त्रेण प्रकृतिसमवेताग्निसंबन्धिनिर्वापप्रकाशनरूपः प्रकृत्युपकारः कृत इति विकृतेरपि तत्समवेतदेवतासंबन्धिनिर्वापप्रकाशनरूपः स कार्यः। स चाग्निशब्दयुतेन तेन कर्तुमशक्यः। तदाह—[१२ शप०] **मन्त्रस्याग्नीति ॥** नन्वेवमपि संप्रदानत्वस्याबाधादेकारानिवृत्तौ 'सूर्ये' इति स्यादिति चेत्, न, अकारान्तेतरप्रकृतिसंनिधानेनैवैकारेण संप्रदानत्वस्य वाच्यत्वेनाकारान्तप्रकृतिसंनिधौ यच्छब्देन वाच्यत्वेनाग्निशब्दनिवृत्तौ तस्यापि निवृत्तेः। तथा च तद्घटितदृश्यमानं रूपमेव समुदितं समुदितस्थाने कल्प्यते। तदाह—[१३ शप०] **तदुपेति ॥** 'अग्नये' इति पदमपहायेत्यर्थः ॥ **तत्राग्नेरितीति।** प्रकृतावग्निसंबन्धिनिर्वापप्रकाशकमन्त्र इत्यर्थः ॥

[उ० १४ शप] **न मन्त्रत्वमिति। 'अनाम्नाता अमन्त्राः'** इत्यापस्तम्बसूत्रेरिति भावः ॥ एकदेशविकृतन्यायेन लौकिकेन मध्यामादिवद् भूयसा व्यपदेश इति न्यायेन च क्रमेणाह—[१५ शप०] **अनेकपदेति।** अवशिष्टेत्यादिः ॥ **तद्घटिते** कल्पितपदघटिते ॥ [१६ शप०] **प्रकृत्यूह इति।** एकाररूपप्रत्ययोऽस्तु नान्तरीयकः, तदर्थस्याबाधात् ॥ एतेन **'सोऽयमुभयोहः'** इति कृष्णोक्तमपास्तम् ॥ प्रकृतिलिङ्गोहस्तु—**देवीरापः शुद्धाः** स्थ इत्यपद्ध विनियुक्तमन्त्रस्याज्ये **'देवाज्य शुद्धमसि'** इति ॥ वचनोहोऽप्ययम्—आप इत्येवंपरसंख्यारोपकृतबहुवचनसत्त्वात् ॥ वचनमात्रोहस्तु—**'मा भैर्मा संविक्था'** इति पुरोडाशेऽवदानमन्त्रस्य धानास्ववदाने **'मा भैष्ट मा संविग्ध्वम्'** इत्यादिं इति मिश्रादयः ॥ याज्ञिकास्तु 'संविग्ध्वम्' इत्यूहमाहुः ॥ तत्र वेदभाष्ये **हे पुरोडाश मा भैः—भयं मा कार्षीः, मा च संविक्थाः—कम्पितो इत्यर्थ** इति ओविजीत्यस्य रूपम्, इडभावश्छान्दसत्वादागमशास्त्रानित्यत्वाद्वा। विजिरस्तु न, तस्य कम्पनार्थत्वाय धातूनामनेकार्थत्वाश्रयणापत्तिरित्याशयेनोक्तमिति तद्विरोधापस्या याज्ञिकोक्तं न युक्तमिति तदेव युक्तमिति हरदत्ताशयः ॥ याज्ञिकाशयस्तु—तदपेक्षया छान्दसत्वादिकल्पना गरीयसीति प्रकृतावनिद्धकतया विजिर एवायं प्रयोगो न तु तस्येति ॥ वस्तुतस्तु **ओविजी** इत्यस्य रूपे **मा भैः** इत्यस्य वैयर्थ्यम्, तस्यैव तत्प्रादिना विशेषतात्पर्यग्राहकाभावेन च स्वदिष्टार्थद्वयसंभवात्। तस्माद्विजिर एव रूपम्। पृथग्भावं मा मन्यस्व इति स्वर्थं इति बोध्यम् ॥ तदेतदभिप्रेत्याह—[१६ शप०] **अन्येऽप्यूह्या इति ॥ संभवादाह—इहशेति ॥** हिरर्थे सिद्धिपदोत्तरं योज्यः ॥ तेन प्रागुक्तरीत्या स्वर्गसुखादिसमुच्चयः। अनेनैवंरीत्या पूर्वत्राप्यैहिकसुखसिद्धेः फलत्वं सूचितमिति बोध्यम् ॥ तावताप्युक्तरीत्या तत्र साक्षात्त्वस्य बाधितत्वात्कैयटोक्तं पारम्पर्यमविरुद्धम् ॥ न्यूनतां परिहरति—**भाष्ये लिङ्गेति ॥ चेन** विभक्तिसमुच्चयः ॥

[भाष्ये] क्रमप्राप्तमागममाह—**आगमः खल्वपीति।** शेषपूरणादि प्राग्वत् ॥ तमेवागमं दर्शयति—**ब्राह्मणेनेति ॥**

[भाष्ये] अवश्याध्ययनायैवान्याङ्गतोऽस्य वैलक्षण्यमाह—भाष्ये—**प्रधानं चेति।**

[भाष्ये] एतदेवाह—भाष्ये—**प्रधाने चेति ॥** क्वचित्तथा पाठः ॥ अत एवोद्द्योते तथा पाठो धृतः ॥

[प्रदीपे] यत्तु यदप्यागम्यते-प्रमीयते हिताहितप्राप्तिपरिहारा-अनेनेत्यागमः—अनादिरुपदेशः प्रत्यक्षानुमानिकश्रुतिरूपः, तथाप्यत्रागमशब्देन तत्फलं लक्ष्यते। तच्च नियोज्यस्य हिताहितप्राप्तिपरिहाररूपम्, उपदेशस्य नियोज्यप्रयोजनैकसाध्यत्वात् इति केनचिदुक्तम्। तन्न, आगमशब्दस्य लाक्षणिकत्वे निर्मूलमुख्यार्थत्यागापत्तेः। उत्तरग्रन्थासंबद्धत्वापत्तेः। अस्य प्रत्यक्षवेदेष्वनुपलम्भेन प्रत्यक्षश्रुतरूपत्वात्। अनुमापकाभावादनुमितत्वस्याप्यभावाच्च। न च व्याकरणाध्ययनेनैवास्यानुमानम्, अन्योन्याश्रयापत्तेः, एतदध्ययनेन तदनुमानम्। तदनुमितेन चैतदध्ययनमितीति दिक्। तदेतद्ध्वनयन्नाह कैयटे—**आगमः प्रयोजन इति ॥**

[प्रदीपे] ननु रक्षादिरूपफलसत्त्वेन कथं तदभावोऽत आह—कैयटे [१ शप०] **अनपेक्ष्येत्यर्थ इति ॥** तथा च न तदभावः

वपि जनमेजयाद्युपाख्यानवत्पौरुषेयव्याकरणस्यापि नित्यताबोधनमुपपद्यते । यद्वा 'तेन प्रोक्तम्' इति सूत्रोक्तभाष्यरीत्या वेदार्थवद्व्याकरणार्थोऽपि 'अनादिस्वरूपनित्यतावान्' इति श्रुत्या तस्य नित्यत्वबोधनमिति बोध्यम् । धर्मत्वं च वेदस्य पुरुषफलसाध्यतया धर्मत्वेनाभिमताध्ययनज्ञानकर्मत्वेनौपचारिकमित्याहुः ॥ षडङ्गः–शिक्षा-कल्प-व्याकरण-निरुक्त-छन्दो-ज्योतिषाङ्गसहितः, वेदः–स्वशाखारूपः, अध्येयः–प्रेरणाविषयाध्ययनकर्म वेद इति बोधः ॥ यद्यपि 'तेन प्रोक्तम्' इति सूत्रे भाष्ये वक्ष्यमाणया रीत्या वेदत्वं शब्दतदर्थोभयवृत्ति, तथापि 'ज्ञेयः' इत्यस्य 'सम्यगर्थबोधपर्यवसाय्यध्ययनं कार्यम्' इत्यर्थे तात्पर्यम् । अत एव **'समानमीहमानानामधीयानानां च केचिदर्थैर्युज्यन्ते केचिन्न'** इति वक्ष्यति भाष्यकृत् । अध्ययनतथाज्ञानयोश्च समुच्चयः । अनेनाताहृशस्याधर्मत्वं सूचयति । श्रुत्या मिलितस्यैव धर्मत्वबोधनात् । तथा च **व्यासः**—

"वेदार्थज्ञो जपं जप्त्वा तथैवाध्ययनं द्विजः ।
कुर्वन् स्वर्गमवाप्नोति नरकं तु विपर्यये" इति ॥

जपपदं मन्त्रसाध्यकर्ममात्रोपलक्षणम् ॥ ज्ञाधातोश्च ज्ञानानुकूलो मनःप्रणिधानविषयेन्द्रियसंयोगसंपादनादिरूपो व्यापारोऽर्थः, तस्यैवात्र विधेयत्वम् । एतेन—ज्ञानस्याविधेयत्वादिदं **चिन्त्यमित्यपास्तम्** ॥

प्रतिपाद्यते, किंतु प्रवृत्तौ तदनपेक्षा, नित्यत्वादेव प्रवृत्तिसिद्धेः । अत एव द्वैरूप्यं प्रागुक्तम् ॥

[प्रदी० ५ मप०] **निमित्तत्वात्**–निमित्तकत्वात् ॥ **सन्मूलत्वात्**-पदपदार्थधीनिमित्तकत्वात् ॥ **वाक्यार्थेति** । वेदार्थावगमस्येत्यर्थः ॥

[उ० १ मप] **व्याकरणफलत्वमिति**–षष्ठीतत्पुरुषः । कैयटस्थप्रयोजनशब्दोऽपि फलपर इति भावः ॥ ननु नित्यकर्मतामित्यस्य नित्यतामित्यर्थे कर्मपदानर्थक्यम्, **किंच** रक्षादिप्रयोजनसत्त्वे कथं निष्प्रयोजनत्वेन नित्यत्वम्, नित्यत्वे वा कथं रक्षादिप्रयोजनोक्तिः । न चैकस्य द्वैरूप्यम्, विरोधादत आह—[२ मप०] **एतेनेति** । कर्मपदयुक्तकथनेनेत्यर्थः । फलाभिसन्धिना यत् क्रियते तत्–कर्मेति व्युत्पत्त्या च कर्मपदं काम्यपरम् ॥ **"एकस्य तूभयत्वे संयोगपृथक्त्वम्"** इति (पू. मी. ४।३।४) न्यायेन 'प्रमाणद्वयसंबन्धादेकस्यापि द्वैरूप्यम् इत्यर्थकेन' **'खादिरो यूपो भवति खादिरं वीर्यकामस्य'** इति विहितखादिरोदाहरणकेनात्र द्वैरूप्ये न विरोधः ॥ अत एव फलचतुष्टयवहिर्भावेनैवादावन्ते वाऽऽगमे वाच्ये मध्ये तदुक्त्या फलसंदंशपातेन नित्यस्यापि फलमस्तीति सूचितमिति भावः ॥ ननु निष्कारणशब्देन नित्यत्वं साङ्गवेदस्य प्रतिपाद्यम् । तदयुक्तम्, आनुपूर्व्या अनित्यत्वात्, तस्य काम्यत्वासंभवाच्च ॥ अङ्गानां तत्त्वस्य दूरापास्तत्वाच्च, तावतापि प्रकृतेष्टासिद्धेश्च । अत आह—[उ० ३ मप०] **नित्यत्वं चेति** ॥ **नयोरिति** । धर्मत्वेनाभिमतयोरिति भावः ॥ [४ धप०] **अत्रेति** । आगम इत्यर्थः ॥ **रन्यस्यैवमध्ययनमिति** ॥ क्षत्रियस्य वैश्यस्य च साङ्गं वेदाध्ययनं तथा ज्ञानं चेत्यर्थः ॥ [५ मप०] **कश्चिदिति** । रजकादित्यर्थः ॥ अत्रारुचिबीजं तयोर्नित्याध्ययनविधायकस्मृत्यन्तरादिविरोधापत्तिरिति ॥ तस्माद्ब्राह्मणपदं त्रैवर्णिकोपलक्षणमिति बोध्यम् ॥ वस्तुतस्तु कलौ क्षत्रियवैश्ययोरभावं सूचयितुं तथोक्तमिति यथाश्रुतमेव तत् साधु । तथा च—

'कलौ न क्षत्रियाः सन्ति कलौ नो वैश्यजातयः ।
ब्राह्मणाश्चैव शूद्राश्च कलौ वर्णद्वयं स्मृतम् ॥'

इति स्मृतिरिति तत्त्वम् ॥ **निष्कारण इति**–इति प्रतीकान्तर्गतप्रतीकम् ॥ यद्वा—**'निष्कारण इति'**-इत्यत्र भाष्ये ॥ ननु निष्कारणशब्दस्य निर्हेतुपरतया लब्धस्यानादित्वरूपनित्यत्वस्य वेदे कथंचित्संभवेऽप्यङ्गानां पौरुषेयत्वेन तत्त्वाभावः ॥ किंचाध्ययनज्ञानयोस्तत्त्वाभावापत्तिरत आह—[५ मप०] **कारणेति** । कार्यतेऽनुष्ठाप्यतेऽनेनेति व्युत्पत्तेः । तथा च ततो निर्गतो निष्कारणो नित्य इति यावदिति तदर्थो बोध्यः ॥

[उद्योते] तद्ध्वनयन्नुक्तरीत्या यथाश्रुते तस्य तदनिष्टत्वादसंगतिपरिहारायाह—[उ० ७ मप०] **अध्ययनेति** । आदिना ज्ञानपरिग्रहः । **ब्राह्मणेनेत्यस्य** तादृशो वेदोऽध्येयो ज्ञेयश्चेत्यनेनान्वयः ॥ तथा च संध्योपासनादिवत्साङ्गवेदाध्ययनतदर्थज्ञानरूपोऽयं धर्मो नित्य इति फलितम् ॥ यथा नित्यस्याकरणे प्रत्यवायस्तत्करणे च तदभावः, तथा व्याकरणाध्ययनस्याननुष्ठानेऽनुष्ठाने च बोध्यम् ॥ यत्तु—**"ब्राह्मणेन—"** इत्यादिः श्रुतिर्न, पठ्यमानवेदेषु अनुपलम्भात् । तस्मात् स्मृतिरेवेयम्–इति भट्टैरुक्तम् । तन्न, भाष्योक्तागमपदास्वारस्यापत्तेः, तस्य वेदपरत्वेनोपपत्तौ उपचरितस्मृतिपरत्वानौचित्याच्च, पठ्यमानस्मृतिष्वनुपलम्भस्य तुल्यत्वाच्च । भगवतः सिद्धानुवादकत्वेन भाष्यीयत्वाद्यभावाच्च । तदेतद् ध्वनयन्नाह—[८ मप०] **आगमेति** ॥ नन्वेवं पौरुषेयव्याकरणस्य कथमागमबोध्यत्वम् । न चैवं स्मृतिरेवेयमास्ताम्, पौरुषेयतयाऽस्या आगमत्वोक्त्यसांगत्यापत्तेः ॥ न च वेदमूलकत्वे तस्याः स्मृतेरप्यागमत्वम्, नित्यानित्यसंयोगविरोधात् । स्मृतेर्वेदमूलकतया स्मृतिविधेयस्य वेदविधेयत्वं स्वीकार्यम्, न चैतत् संभवति–व्याकरणस्यानित्यस्याध्ययनं नित्येन वेदेन विधीयते इति, अत आह—**श्रुतावपीति** । तथा च तद्व्रवाहनित्यतया नित्यविधिविषयत्वोपपत्तिः । न च प्रत्यक्षश्रुत्यमूलकत्वान्न ते प्रवाहनित्यत्वकल्पनं युक्तम्, **"तस्मादियं व्याकृता वागुद्यते"** इति प्रत्यक्षश्रुतिमूलकत्वसत्त्वात् । पूर्वकाले **"अग्निमीळे"** इत्यादिका वागेकात्मिका विभागशून्याऽऽसीत् । ततो विभागार्थं देवैः प्रार्थित इन्द्रो देवान्प्रति इन्द्रेण याचित एकपात्रे वायोः स्वस्य च सोमरसग्रहणरूपे वरे देवैस्तथा करणेन संतुष्टो विभागं कुर्यादित्यर्थकमिदं श्रुताबुक्तम् ॥ न च संप्रदायव्यावृत्तनित्यवेदाभिप्रायेयम्, **वागुद्यत** इत्येव सिद्धे **व्याकृता** इत्यस्यानर्थक्यापत्तेः । तस्मादियं वागिदानीमपि पाणिन्यादिभिर्व्याकृतोच्यत इत्यर्थकमिदं श्रुताबुक्तम् ॥

[उ० १० मप०] सिद्धान्तमतेनाह—**यद्वेति** ॥ ननु **'चोदनालक्षणोऽर्थो धर्मः'** इति धर्मलक्षणानाक्रान्तत्वात् कथं वेदस्य धर्मत्वमत आह—[१२ शप०] **धर्मत्वं चेति** ॥ यत्तु–वेदोपकारित्वाच्छ्रुतिलिङ्गादिषट्कमेवाङ्गम्, शब्दात्मकत्वेन तेषां श्रुत्यवयवत्वसंभवात्–इति, तन्न; तथा सत्यध्येयो ज्ञेयश्चेत्येव सिद्धे षडङ्ग इत्यस्य वैयर्थ्यापत्तेः । तद् ध्वनयन्नाह—[१४ शप०] **शिक्षेति** ॥ [१४ शप०] **सहित इति** । अनेन बहुव्रीहिः सूचितः ॥ यत्तु—न तेषामङ्गत्वम्, तद्धि तादर्थ्यात्तदवयवत्वाद्वा वाच्यम् । तत्र

ननु गुणानां परस्परसंबन्धाभावात् 'षडङ्गेषु प्रधानम्' इत्यनुपपन्नमत आह-**षडेति** । एवं च वेदार्थज्ञाने व्याकरणं प्रधानं कारणमिति भावः ॥ भाष्ये—**प्रधाने कृतो यत्न इति** । प्रधानविषये निर्वृत्त इत्यर्थः । अन्यथा यत्नविषयकृतेरसंभवादसंगतिः स्पष्टैव ॥ भाष्ये—**'फलवान्'** इत्यत्र फलपदेन वाक्यार्थावगमो विवक्षितः । एतच्छास्त्रं च पदपदार्थावगमद्वारा वाक्यार्थावगमोपयोगीति बोध्यम् ॥ एवञ्च व्याकरणानध्ययनप्रयुक्तस्य वेदार्थाज्ञानप्रयुक्तस्य च प्रत्यवायस्य परिहारकतयाऽस्य नित्यत्वमिति बोध्यम् ॥

(लघुपदार्थनिरूपणभाष्यम्)

लघ्वर्थं चाध्येयं व्याकरणम् । "ब्राह्मणेनावश्यं शब्दा ज्ञेयाः" इति, न चान्तरेण व्याकरणं लघुनोपायेन शब्दाः शक्या विज्ञातुम् ॥

(प्रदीपः) **लघ्वर्थमिति** । लाघवेन शब्दज्ञानमस्य प्रयोजनम् ॥ **ब्राह्मणेनेति** । अध्यापनं ब्राह्मणस्य वृत्तिः । न चाशब्दज्ञं तमुपश्लिष्यन्ति शिष्या इति ॥

(उद्द्योतः) 'अवश्यम्'इत्यनेन विवक्षितं दर्शयति—**अध्यापनमिति** । लाघवं च प्रतिपदपाठापेक्षया प्रकृत्यादिविभागेनान्वाख्यानस्य विवक्षितम् ॥

नाद्यः, तादर्थ्यबोधकश्रुत्याद्यभावात् । नान्त्यः, अनित्यस्य नित्यावश्यकत्वायोगात्-इति । तत्र, **'मुखं व्याकरणं प्रोक्तम्'** इत्यनेनाङ्गत्वेन संस्तवादुपकारकत्वाद्वाऽङ्गत्वसंभवात् ॥ यत्तु-वेदत्वावच्छिन्नस्य सकलशाखस्येदानीमध्ययनाद्यसंभवात्कलिकालप्रधानपाणिनिव्याकरणेन सह तस्य तत्प्रतिपादनमयुक्तम्-इति, तन्निरासायाह—**स्वेति** ॥ अयं चार्थो बोध्यः ॥ अध्येये यत् कर्मणि जायमानः 'प्रैषा-' इति सूत्रेण विधिरूपत्वे । तदाह—[१५ शप०] **अध्येय इत्यत** इति । व्युत्पत्तिवैचित्र्यात्तथाऽन्वय इति भावः ॥ [१७ शप०] **निष्ठमिति** । व्यासज्यवृत्तीत्यर्थः । एवं च शब्दस्य साक्षादध्ययनवदर्थस्य ज्ञानद्वाराऽध्ययनसंभवादर्थबोधपर्यवसाय्यध्ययनं कार्यमित्यर्थाच्चाध्येय इत्येव सिद्धे ज्ञेय इति व्यर्थमिति भावः । अत एव सामर्थ्यादाह—[१७ शप०] **सम्यगिति** ॥ नन्वध्ययनमात्रेण सम्यगर्थबोधस्यैव जायमानत्वेनेदमयुक्तम्, अत आह—[१८ शप०] **अत एवेति** । तस्योक्तार्थतात्पर्यकत्वादेवेत्यर्थः ॥ [२० शप०] **तथेति** । सम्यगर्थविषयकज्ञानेत्यर्थः ॥ **समुच्चय इति** । **'अहरहर्नयमानो गामश्वं पुरुषं पशुम्'** इतिवत् विना चं समुच्चय इत्यर्थः ॥ क्वचित् **'ज्ञेयश्च'** इत्येव पाठः ॥ [२०शप०] **नातादृशस्येति** । प्रत्येकस्येत्यर्थः ॥ अनेनेत्यस्यार्थमाह—**श्रुत्येति** ॥ अत्र संमतिमाह—[२१ शप०] **तथा चेति** ॥ जप्त्वा-जपं कृत्वा । तथाशब्दः समुच्चये ॥ एवः क्रियावधारणे ॥ विपर्यये प्रत्येककरणे ॥ न्यूनतां परिहरति—[२४ शप०] **जपेति** ॥ मन्त्रस्यैव जपसत्त्वादाह—**मन्त्रेति** ॥ विनिगमनाविरहादाह—**मात्रोपेति** ॥ कस्यचिदुक्तिं खण्डयितुं सर्वात्मनाऽध्येय इत्येतत्तुल्यतां ज्ञेय इत्यत्र कथयति—[२४ शप०] **ज्ञाधातोरिति** ॥ आदिना स्मित्यादिपरिग्रहः ॥ **तस्यैवेति** । तावतैव ज्ञानविधित्वसिद्धेः । फूत्कारादिविधिना पाकविधिवदिति भावः ॥ [२४ शप०] **ज्ञानस्येति** । तस्य कर्तुमकर्तुमन्यथाकर्तुं चाशक्यत्वाद्वाक्यादिरूपप्रमाणपरतन्त्रस्य तस्य विधेयताया असंभवाच्चेति भावः ॥ [२६ शप०] **पाप्तमिति** । उक्तयुक्तेः । प्रतिमादावीश्वरबुद्धिवत्तस्यापि तथा कर्तुं शक्यत्वाच्चेति भावः ॥

[उद्द्योते] तत्र वर्तमानं स्वाङ्गापेक्षया प्रधानमिति न भाष्यार्थः । तदपेक्षया तस्यस्य शिक्षादावप्यविशिष्टत्वात् । अतः तेषां मध्ये यत् प्रधानम् अर्थात् तन्निरूपितप्राधान्यवद् इति तदर्थो वाच्यः सोऽपि न, अङ्गानां मिथोऽसंबन्धेन गुणप्रधानभावाभावात् । तदाह—[उ० २६ शप०] **ननु गुणेति** ॥

[उद्द्योते] फलितमाह—[उ० २८ शप०] **एवं चेति** । अस्य तन्मूलतन्निमित्तत्वे चेत्यर्थः ॥ **ज्ञाने**-ज्ञानं प्रति । एवं च षड्स्वङ्गेषु वर्तमानं व्याकरणं वेदार्थज्ञानं प्रति प्रधानं-मुख्यं कारणमिति तदर्थो बोध्यः ॥ स्वरूपार्थप्रतिपत्तिभ्यामस्य तदुपकारकत्वमिति सर्वोपजीव्यत्वादस्य प्राधान्यम्, अन्येषां त्वेकदेशे व्यापारः । यथा चैतत्तथाऽन्यत्र स्पष्टम् ॥ अत एवाङ्गत्वेन संस्तवेऽप्यस्य मुखत्वेनोक्तिः । यथा सर्वशरीरावयवानां मध्येऽन्नपानादिप्रवेशनद्वारा शरीरनिर्वाहकं मुखम्, एवमिदमपि वेदस्वरूपनिर्वाहकमिति भावः ॥

[उ० २९ शप०] **प्रधानेति** । व्याकरणाध्ययनविषय इत्यर्थः ॥ 'कृतः' इत्यस्यार्थमाह—**निर्वृत्त इति** ॥ **अन्यथा**-उक्तार्थाभावे ॥ ननु फलवानित्यत्र फलशब्दस्य व्याकरणज्ञानार्थकत्वे उक्तार्थाप्रतिपादकत्वापत्तिरत आह—[३१ शप०] **फलेति** ॥ **वाक्यार्थेति** । वेदार्थेत्यर्थः ॥ एवमग्रेऽपि ॥ फलितमाह—**एतदिति** ॥ [३२ शप०] **वाक्यार्थेति** । वाक्येत्यादिः ॥ परमपर्यवसितमुपसंहरति—**एवं चेति** ॥ अस्य तथा तदुपयोगित्वे चेत्यर्थः ॥

[१ मभाष्ये] क्रमप्राप्तं लघुरूपप्रयोजनमाह—भाष्ये—**लघ्वर्थं चेति** ॥ सकलसाधुशब्दज्ञानहेतुभूतप्रक्रियारूपलघुभूतोपायज्ञानार्थमित्यर्थः ॥

[भाष्ये] ननु किमर्थं साधुशब्दज्ञानं यदर्थं तादृशोपायज्ञानापेक्षा, अतस्तत्र हेतुमाह—भाष्ये—**ब्राह्मणेनेति** । अत्रापि क्षत्रियविशोरध्यापनाभावादुक्तहेतोश्च 'ब्राह्मणेन' इत्युक्तम् ॥ **इति**-हेतौ ॥

[भाष्ये] एतदेवाह—भाष्ये—**न चान्तेति** ॥ व्याकरणाध्ययनं विना न हीत्यर्थः ॥ प्रतिपदपाठरूपगुरूपायस्य सत्त्वादाह—**लघुनोपायेनेति** । लघुभूतेनोक्तान्योपायेनेत्यर्थः ॥ क्वचित् **'उपायान्तरेण'** इत्येव पाठः ॥

[प्रदीपे] तत्फलितमाह कैयटे—**लाघवेनेति** ॥

[प्रदीपे] ननु तस्य वृत्तित्वेऽपि प्रकृते किम्, अतो व्यतिरेकमुखेन तद् द्रढयन्नाह—कैयटे—**न चाशब्दज्ञमिति** । 'अपशब्दज्ञं' इत्यपपाठः । एवं च वृत्त्यनिर्वाह इति तदावश्यकत्वम् । **'न च-'** इत्यस्य न हीत्यर्थः ॥ **इति**-समाप्तौ ॥

[उद्द्योते] वृत्तिविधिं विनैव सिद्धस्यार्थस्यानुवादेन विधिकल्पने मानाभावं ध्वनयन्नाह—उद्द्योते—**अवश्यमिति** । विधिकल्पकत्वे तु तदानर्थक्यं स्पष्टमेव ॥

[उद्द्योते] कैयटोक्तलाघवं न शब्दज्ञाननिष्ठमित्याह—उद्द्योते—**लाघवं चेति** ॥ **प्रतिपदेति** । आनन्त्येन तस्य कर्तुमशक्यत्वात् ॥ **प्रकृत्येति** । सामान्यविशेषलक्षणवच्छास्त्रबोध्येनेति भावः ॥

(असंदेहपदार्थनिरूपणभाष्यम्)

असंदेहार्थं चाध्येयं व्याकरणम् । याज्ञिकाः पठन्ति—'स्थूलपृषतीमाग्निवारुणीमनड्वाहीमालभेत' इति । तस्यां संदेहः-स्थूला चासौ पृषती च, स्थूलानि वा पृषन्ति यस्याः सा-स्थूलपृषतीति । तां नावैयाकरणः स्वरतोऽध्यवस्यति । यदि पूर्वपद-प्रकृतिस्वरत्वं ततो बहुव्रीहिः, अथ-अन्तोदात्तत्वं ततस्तत्पुरुष इति ॥

(प्रदीपः) **असंदेहार्थमिति** । संदेहस्य प्रागभावोऽत्र द्रष्टव्यः, न तु प्रध्वंसाभावः । न हि वैयाकरणस्य संशय उत्पद्य विनश्यति, इतरस्यैव तदुत्पादात् ॥ **स्वरत इति** । पूर्वपद-प्रकृतिस्वराद्बहुव्रीह्यर्थावसाय इत्यर्थः ॥

(उद्द्योतः) नन्वसंदेहः=संदेहाभावः । स च नात्यन्ताभावः, तस्य नित्यत्वात् । न च ध्वंसः, तत्तद्विषयकव्याकरणज्ञानवतः संदेहस्यैवाभावेन तदसंभवात् । यस्य स्वधीतव्याकरणस्यापि क्वचित्संदेहः, स तद्विषयकवैयाकरणत्वाभाववानेव, वेदनार्थे हि तत्र प्रत्ययोऽत आह—**प्रागभाव इति** । तत्परिपालनं च शास्त्राध्ययनफलम् । न तु स्वरूपं, तस्याजन्यत्वात् । तत्पालनं च प्रतियोगिजनककारणविध्वंसनं, प्रागभावस्य प्रतियोगिजन्मनाश्यत्वात्-इति बोध्यम् ॥ भाष्ये-**याज्ञिकाः पठन्तीति** । यज्ञकाण्डभवा वैदिकाः शब्दाः-याज्ञिकाः, ते पठन्तीत्यर्थः । **'ऋषिः पठति' 'शृणोत ग्रावाणः'** इतिवत्प्रयोगः । तत्र ऋषिः=वेदः । सन्सूत्रे भाष्ये एष प्रयोगः । **ताम्-अनड्वाहीम्** । कस्तर्हि निश्चयस्तत्राह—**पूर्वपदेति** ॥

[भाष्ये] असंदेहस्य फलत्वं क्रमप्राप्तमाह—**असंदेहेति** ॥ संदेहप्रागभावपरिपालनार्थं चेत्यर्थः ॥

[भाष्ये] ननु कुत्रावैयाकरणस्य संदेहोऽत आह—भाष्ये—**याज्ञिका इति** ॥

[भा० ३ यप०] **तस्यामिति**—भाष्ये । श्रुतावित्यर्थः । स्थूलपृषत्यामित्यर्थोऽनड्वाह्यामित्यर्थो वा ॥ यत्तु—पृषतो मृगविशेषस्तज्जातीया, पृषतजातित्वात् ङीष् । सैवानोवहनयोग्या चानड्वाही—इति कृष्णः । तन्न । तस्या गवि रूढत्वात् । तस्मान्मत्वर्थलक्षणया पृषतीशब्देन पृषद्वती=बिन्दुमती गौरुच्यते, स्थूलाऽपि सैव, बिन्दुषु न । तत्र कर्मधारये गौरेवोच्यते, स्थूलाऽपि सैव । बिन्दुषु न स्थौल्यान्वयः ॥ बहुव्रीहौ तु स्थौल्यान्वयः पृषत्सु, न गवि ॥ न च कर्मधारयस्य स्वपदार्थप्राधान्येन बहुव्रीहेः प्राबल्यादसंदेह एवेति वाच्यम् । अन्यपदार्थप्रधानाग्निवारुणीशब्दसमभिव्याहारेण तस्यापि संभवात् ॥ न च **'व्याख्यानतः'** इति परिभाषया निर्णयः; पौरुषेयेषु लक्ष्यानुरोधेन तया निर्णयेऽप्यपौरुषेयेऽदृष्टार्थविषये वेदे तया तदसंभवात् । तस्मात् स्वरतो निर्णयो वैयाकरणैकसाध्यः । तदेव व्यतिरेकमुखेनाह—भाष्ये—**तामिति** ॥

[भाष्ये] स्वरतोऽध्यवसायप्रकारमाह—[भा० ५ मप०] **यदीति** ॥

[प्रदीपे] कैयटे—**अत्र द्रष्टव्य इति** । न तु सर्वत्रेति भावः ॥ एतेन—'संदेहाभाव एवार्थः । कैयटोक्तं तु चिन्त्यम्, ईदृशाग्रहे मानफलयोरभावात् । अनुभवविरोधात् । शङ्कासमाधिपरसमस्तभाष्यासंगतेश्च'—इति रत्नोक्तम्,—'प्रध्वंस एव सः, उत्पन्नस्य तस्य हि वैयाकरणेन शास्त्राहितसंस्कारवता निरासः सुकरः—' इति कृष्णोक्तं चापास्तम् । उक्तहेतोः । अवैयाकरणवैयाकरणभेदेन भगवता शङ्कासमाध्योरुक्तेश्चेति दिक् । तदाह—कैयटे—**न हीति** ॥ न च व्याख्यातृपरम्परया तदभावात् किमनेन…… …? । प्रतिपदं प्रतिपुरुषं प्रतिक्षणं जायमानसंशयानां तैर्निरसितुमशक्यत्वात् । तेषां सर्वदा सांनिध्याभावाच्च ॥ नचास्यार्थनिश्चायकत्वे गवादीनां पुरुषार्थकताऽपि स्यात्, अर्थमनूद्य शब्दानामिदमनुशासनं नार्थानामिति व्युत्पत्त्यर्थं तदाश्रयणेऽपि यत्र प्रमाणान्तराविरोधः, तत्र तत्सत्त्वमन्यत्र नेत्येवं देवताधिकरणन्यायेनाङ्गीकारात् । स च पदार्थविषयो न वाक्यार्थविषयः । पदानामेवानुशासनादिति बोध्यम् । तदेतद् ध्वनयन् वक्ष्यति—**तां नेति** (भाष्ये) ॥

[प्र० ४ धंप०] कैयटे-**स्वरात्**-पठ्यमानात् ॥ स्थूलशब्दः फिट्स्वरेणान्तोदात्तः । अर्थविशेषाश्रयबहुव्रीहिनिबन्धनपूर्वपदप्रकृतिस्वरस्य तेन विनाऽसंभवात्तस्य निर्णायकत्वं युक्तमिति भावः ॥ अवैयाकरणस्य त्वनिर्णय एव, वृत्तिपदार्थज्ञानादेरप्यभावेन विपरीतनिर्णयस्याप्यभावात् । अन्यस्य कस्यचिल्लौकिकस्य निर्णायकस्यासंभवाच्च ॥ एतेन—तस्य विपरीतनिर्णयः स्याद्—इति कृष्णोक्तमपास्तम् ॥

[उद्द्योते] एतदनभिज्ञः शङ्कते—[उ० १मप०] **नन्वसंदेहेति** ॥ [२ यप०] **नित्यत्वादिति** ॥ एवं च फलत्वासंभवस्तस्य ॥ [३ यप०] **तदेति** । ध्वंसेत्यर्थः ॥ ननु तदध्ययनसत्त्वेन कथं तत्त्वम्, तत्रापि प्रत्ययसत्त्वादत आह—[४ थंप०] **वेदनेति** ॥ यतो वैयाकरणशब्दे इत्यर्थः ॥ उक्तहेतोरिति यावत् ॥ तथा च वैयाकरणत्वमव्याप्यवृत्तीति भावः ॥ तस्याजन्यत्वेनाफलत्वादाह—[५ मप०] **तत्परीति** ॥ **शास्त्रेति** । व्याकरणेत्यर्थः ॥ ननु तस्य निरवयवत्वेन पोषणाद्यसंभवात्कथं परिपालनमत आह—[६ ष्ठप०] **तत्पालनमिति** ॥ **कारणेति** । संदेहजनकप्रतिबन्धकाभावरूपेत्यर्थः ॥ ननु तस्य कथं तत्त्वमत आह—[७ मप०] **प्रागेति** । तथाच कोटिद्वयोपस्थितिः सुतरां नेति भावः ॥

[उद्द्योते] यत्तु—'यज्ञं विदन्ति ते याज्ञिकाः, उक्थादित्वाट्ठक् । पाठसमयेऽध्यापकादीनां निर्णिनीषाया अनावश्यकत्वाद् याज्ञिका इत्युक्तम्, न त्वध्येत्रादयः' इति कृष्णः । तन्न, अस्याः श्रुतित्वेन **'इति श्रूयते तत्र संदेहं कुर्वन्ति'** इति वाच्ये तथोक्त्यसांगत्यापत्तेः । तदेतद् ध्वनयन्नाह—[उ० ८ मप०] **यज्ञेति** ॥ लक्षणयाऽर्थमाह—**काण्डेति** ॥ ननु न तेषां पठनसंभवोऽत आह—[९ मप०]—**ऋषिरिति** ॥ एवं च बोधने लाक्षणिकः प्रयोग इति भावः ॥ तत्र पूर्ववाक्ये तत्प्रयोगस्य निर्मूलत्वं निराचष्टे—[१० मप०] **सन्निति** ॥

[उद्द्योते] पूर्वव्याख्यानासांगत्यं ध्वनयन् स्थूलपृषतीमिति विहाय व्याचष्टे—[उ० १० मप०] **अनड्वाहीमिति** । यद्यपि स्थूलपृषतीशब्देऽर्थसंदेहः, तथापि पर्यन्ततो गव्येव संदेह इति भावः ॥

[उद्द्योते] नन्वेवं भगवता निश्चयो नोक्त इति संशय एवेत्याशयेनाह—[उ० ११ शप०] **कस्तर्हीति** ॥

(व्याकरणाध्ययनसाधकागमप्रतीकभाष्यम्)

इमानि च भूयः शब्दानुशासनप्रयोजनानि—तेऽसुराः । दुष्टः शब्दः । यदधीतम् । यस्तु प्रयुङ्क्ते । अविद्वांसः । विभक्तिं कुर्वन्ति । यो वा इमाम् । चत्वारि । उत त्वः । सक्तुमिव । सारस्वतीम् । दशम्यां पुत्रस्य । सुदेवो असि वरुण-इति ॥

(प्रदीपः) मुख्यानि प्रयोजनानि प्रदर्श्यानुषङ्गिकाणि प्रदर्शयति—**इमानि चेति ॥ भूय इति ।** पुनरित्यर्थः । आनुषङ्गिकत्वाच्चैषां वर्गद्वयोपादानम् ॥

(उद्द्योतः) ननु अम्लेच्छत्वादीनां बहुत्वात् 'बहूनामनुग्रहो न्याय्यः' इति प्रथमतोऽभिधानं युक्तमत आह—**मुख्यानीति ।** प्रधानत्वादेव तेषां प्रथमतोऽभिधानमिति भावः ॥ तेषां प्रधानत्वं च पदपदार्थज्ञानाधीनत्वेनान्तरङ्गत्वात् । वक्ष्यमाणानां च बहिरङ्गशब्दापशब्दप्रयोगविधिनिषेधविषयत्वादानुषङ्गिकत्वं बोध्यम् ॥ ननु **'भूयः'** इत्येकवचनमनुपपन्नं **'प्रयोजनानि'** इत्यनेन सामानाधिकरण्यादत आह—**पुनरिति ॥ इमानि चेति ।** चः-समुच्चये ॥ भाष्ये-**प्रयोजनानीति ।** प्रवर्तकानि फलानि चेत्यर्थः । तत्र वक्ष्यमाणवाक्यानि प्रवर्तकानि, तद्बोध्यानि फलानीति विवेकः ॥ ननु रक्षादिभिः सहैवैतानि कुतो न पठितानि ? इत्यत आह—**आनुषङ्गिकत्वादिति ।** एषामानुषङ्गिकत्वं तेषां प्रधानत्वं बोधयितुं तथोक्तिरिति भावः ॥

(भाष्यम्)

तेऽसुराः—

"तेऽसुरा हेऽलयो हेऽलय इति कुर्वन्तः पराबभूवुः । तस्माद्ब्राह्मणेन न म्लेच्छितवै नापभाषितवै, म्लेच्छो ह वा एष यदपशब्दः" ॥

म्लेच्छा मा भूमेत्यध्येयं व्याकरणम् । तेऽसुराः ॥

(प्रदीपः) **तेऽसुरा हेऽलय इति ।** निन्दाऽर्थवादेन **'न म्लेच्छितवै'** इति म्लेच्छनं निषिध्यते । तत्र केचिदाहुः—**'हैहेप्रयोगे हैहयोः'** इति प्लुते प्रकृतिभावे च कर्तव्ये तदकरणं म्लेच्छनमिति । पदद्विर्वचने कार्ये वाक्यद्विर्वचनं लत्वं च म्लेच्छनमित्यपरे । **न म्लेच्छितवा** इत्यस्य पर्यायः- **नापभाषितवा** इति । **'कृत्यार्थे-'**इति तवैप्रत्ययः॥**म्लेच्छ इति ।** कर्मणि घञ् ॥

(उद्द्योतः) ननु **'पराबभूवुस्तस्माद्ब्राह्मणेन-'** इति श्रुतौ पराभवस्यापशब्दभाषणफलत्वावगतेः 'पराभूता मा भूमेत्यध्येयम्' इति वक्तुमुचितमत आह—**निन्दाऽर्थवादेनेति । 'द्रव्यसंस्कारकर्मसु परार्थत्वात्फलश्रुतिरर्थवादः स्यात्'** (पू० मी० ४।३।१) इति न्यायेन **'यस्य पर्णमयी जुहूर्भवति न स पापं श्लोकं शृणोति'**

[भाष्ये] **इमानीति**-भाष्ये वक्ष्यमाणानीत्यर्थः ॥

[भाष्ये] प्रयोजनेयत्तायाः स्पष्टत्वाय तान्यादौ प्रतीकं धृत्वा गणयति—भाष्ये—**तेऽसुरा इत्यादि ॥ 'विभक्तिं कुर्वन्ति'** इति वाक्यार्थकथनम् । **'सारस्वतीं'** इति तद्वाक्यस्थपदोक्तिः ॥

[उ० २यप०] उद्द्योते—**इतीति ।** इति न्यायेनेत्यर्थः । [४थंप०] **पदार्थज्ञानेति ।** तन्मात्रेत्यर्थः ॥

[उ० ७मप०] **पुनरितीति ।** पश्चादिति तदर्थः ॥ अव्ययमिति भावः ॥ यद्यपि तस्याधिक्यमप्यर्थः, तथापि योग्यतया तस्यैव ग्रहणम्॥ [उ० ८मप०] **चेति ।** पश्चादिति तस्यार्थः । इति-बोध्यानीति शेषः ॥ प्रागुक्तरीत्याऽर्थद्वयं बोध्यम् ॥ तत्र-तयोर्मध्ये ॥

[उ० ९मप०] **ननु रक्षादिभिरिति ।** यद्यप्युक्तरीत्याऽन्तरङ्गबहिरङ्गभावः, तथापि प्रधानत्वाप्रधानत्वयोर्मानाभावः । किं चास्तु तयोरपि सत्त्वम्, तथापि क्रमेण तैः सह पाठ एवैषामुचित इति भावः ॥ [११ शप०] **बोधयितुमिति ।** तथा च तथा पाठे स्वस्य ज्ञानसत्त्वेऽपि परस्य ज्ञानं न स्यादिति परबोधायैव परमुक्तिः ॥ एवं च कैयटे चः-हेतौ । यतो हेतोरानुषङ्गिकत्वमेषाम्, अत इत्यादयों बोध्य इति भावः ॥

[भाष्ये] तत्रादावुद्देशक्रमेणाम्लेच्छत्वं फलं वदन् तद्वाक्यं ब्राह्मणस्थमुक्तप्रतीकसंघटितमाह—भाष्ये—**तेऽसुरास्तेऽसुरा इति ॥** इयं रीतिरग्रे सर्वत्र बोध्या ॥

[भाष्ये] तत्र निषेधस्य सविषयनिन्दापेक्षायां विषयस्य निन्दितत्वं फलमाह—भाष्ये—**म्लेच्छो ह वा इति ॥** यत्=यस्मात् एषोऽपशब्दो म्लेच्छः-म्लेच्छतयाऽतिप्रसिद्ध इत्यर्थः ॥

[भा० ५ मप०] अनपभाषणस्याम्लेच्छत्वफलकत्वाद्व्याकरणाध्ययनस्याम्लेच्छत्वं फलम्-इत्युपसंहृतदाख्याय पुनः **'तेऽसुराः'** इत्युक्तम् ॥ एवमग्रे सर्वत्र ज्ञेयम् ॥

[प्रदीपे] ननु किमनृतं यत्कृतस्तेषां पराभवः, अत आह—कैयटे [२ यप०] **तत्रेति ।** श्रुतावित्यर्थ. ॥ [३ यप०] **प्रकृतीति ।** तत्प्रयुक्तेत्यादिः ॥ **'प्लुतप्रगृह्याः'** इत्यनेनेति भावः ॥

[प्र० ६ष्ठप०] अत एवाह—कैयटे—**कृत्यार्थ** इति ॥ उभयत्रेत्यादिः ॥

[प्रदीपे] यत्तु—कर्मणि करणे वा घञ्—इति कृष्णः । तन्न, करणे तस्य दौर्लभ्यात् । तद्ध्वनयन्नाह कैयटे [६ ष्ठप०] **कर्मणीति ॥**

[उद्द्योते] **'तेऽसुराः'** इत्यादेः श्रुतित्वेऽप्यनर्थयुक्तत्वादात—उद्द्योते—**परेति ॥** [३ यप०] **निन्दाऽर्थवादेनेतीति ।** तृतीयया पूर्वत्वं सूच्यते । तथाच निन्दाऽर्थवादपूर्वकं 'न म्लेच्छितवै' इत्यनेन म्लेच्छनं निषिध्यते-न विधीयत इति कैयटार्थो बोध्यः ॥ न च **'तेऽसुराः'** इति आर्थवादिकफलनिर्देश एव, **'म्लेच्छो ह'** इत्यस्य वाक्यस्यानर्थक्यापत्तेः । न च म्लेच्छस्वरूपप्रदर्शनाय तत्, **'नापभाषि—'** इत्यनेनैव गतार्थत्वात् ॥ तस्मात् कर्माङ्गेऽपशब्दनिषेधे फलश्रुतेरर्थवादत्वमेव न्याय्यम् । तदाह—**द्रव्येति ।** जैमिनीयमिदम् । अस्यार्थः कौस्तुभव्याख्यातोऽवगन्तव्यः ॥ तत्र द्रव्यस्योदाहरणमाह—[५ मप०] **यस्येति ॥** [५ मप०] **स पा-**

इत्यादावपापश्लोकश्रवणस्य प्राशस्त्यमात्रपरत्ववदस्य निन्दामात्रपरत्वादिति भावः । प्रकरणाच्च क्रत्वङ्गोऽयं निषेधः ॥ केचिदाहुरिति । अत्रारुचिबीजं तु 'सर्वैः प्लुतः साहसमनिच्छता विभाषा कर्तव्यः' इति ॥ पदेति । 'सर्वस्य द्वे' इत्यत्र पदग्रहणस्य वार्तिककृतोक्तत्वादिति भावः ॥ ननु नेदं द्वित्वं, किं त्वैच्छिकः पुनः प्रयोगोऽत आह—त्वर्थं चेति । 'न म्लेच्छितवै' इत्येतत् म्लेच्छभाषाविषयमिति भ्रमनिवृत्त्यर्थं तद्विवरणं-'नापभाषितवै' इति । 'ह वै' इति-प्रसिद्धौ । अपशब्दत्वं व्याकरणानुगतशब्दस्यैषद्भ्रंशन एव प्रसिद्धमिति भावः ॥ ननु म्लेच्छो नाम पुरुषविशेषो देशविशेषो वा, स कथमपशब्दोऽत आह—एवमिति । निन्दावचनान्म्लेच्छेरिति भावः । निन्दा च शास्त्रबोधितविपरीतोच्चारणेन पापसाधनत्वात् । एवं च म्लेच्छा इत्यस्य निन्द्या इत्यर्थ इति दिक् ॥

(भाष्यम्)

दुष्टः शब्दः—

"दुष्टः शब्दः स्वरतो वर्णतो वा
मिथ्याप्रयुक्तो न तमर्थमाह ।
स वाग्वज्रो यजमानं हिनस्ति
यथेन्द्रशत्रुः स्वरतोऽपराधात् ॥" इति ॥

दुष्टाञ्छब्दान्मा प्रयुक्ष्महीत्यध्येयं व्याकरणम् ॥

दुष्टः शब्दः ॥

(प्रदीपः) दुष्टः शब्द इति । स्वरेण-स्वरतः, आद्यादित्वात्तसिः ॥ मिथ्याप्रयुक्त इति । यदर्थप्रतिपादनाय प्रयुक्तस्ततोऽर्थान्तरं स्वरवर्णदोषात्प्रतिपादयन्नाभिमतमर्थमाहेत्यर्थः । वागेव वज्रो हिंसकत्वात् । यथेन्द्रशत्रुशब्दः स्वरदोषाद्यजमानं

चेति । पापश्लोकश्रवणाभावस्येत्यर्थः ॥ प्राशस्त्येति । 'पर्णमयी जुहूः' इत्यादिः ॥ मात्रपदेन स्वार्थपरत्वनिरासः ॥ एवमग्रेऽपि ॥ अस्य-तेऽसुरा इत्यर्थवादस्य ॥ ननु निषेधे द्रव्यत्वाभावेनानङ्गत्वेन तदन्यान्यतरत्वस्याप्यभावेन दृष्टान्तवैलक्षण्यात्कथं 'क्रत्व—' इति न्यायसंचारोऽत आह—[७ मप०] प्रकेति ॥ चरस्त्वर्थः । 'क्रत्वङ्गमयम्' इति पाठः । अङ्गशब्दस्य नित्यक्लीबत्वात् ॥ यत्तु 'यर्वाणो नाम' इत्याद्युत्तरत्र भगवदुक्तेरयं निषेधः क्रत्वङ्गम्—इति कृष्णः । तन्न, प्रकरणलभ्यस्यैवार्थस्याग्रे भगवता कथनात् ॥

[उद्योते] यत्तु रत्नकृत्—'इदमयुक्तम् 'ई चाक्रवर्मणस्य' इत्यप्लुतवद्भावस्य 'ई'ग्रहणाभावेनान्यत्रापीष्टत्वेनात्र प्लुते सत्यपि पूर्वरूपसंभवात्, पूर्वरूपं जायमानं प्लुतात्मकमेव भवतीति तदनुच्चारणं दोषः—इति तु युक्तम्'—इति । तन्न, हैहे...............
... । तदेतद् ध्वनयन्नाह—[७ मप०] अत्रेति ॥ अत एवाह—[९ मप०] पदेतीति ॥ यत्तु—'पदस्य' इत्यधिकारात्—इति कृष्णः । तन्न, तस्याग्रे स्वरेऽपि पूर्वमभावात्; अत आह—[९ मप०] तोक्तत्वादिति । यदि तु 'सर्वस्य' इतिसूत्रस्थ'पदस्य' इत्यस्याप्यधिकारः—इत्युच्यते, तर्हस्तु सोऽपि साधुः ॥ यत्तु रत्नकृत्—असुरोक्त्यनुकरणतया पदस्यानापन्नस्यैव वेदे द्विरुक्तत्वेन वाक्यद्वित्वस्य तैरकृतत्वादिदमयुक्तम्, बहुकृत्वो वाक्यप्रयोगस्तु वीप्साद्योतनार्थम्-इति, तन्न, मिथोविरुद्धत्वात् । अन्यथानुकरणत्वासंभवाच्च । तदेतद् ध्वनयन्नाह—[१० मप०] ननु नेदमिति ॥ पुनरिति । तात्पर्यद्योतनार्थमिति शेषः ॥ 'अनावृत्तिः शब्दात् अनावृत्तिः शब्दात्' इति व्याससूत्रवदिति भावः ॥ आम्रेडितस्वररहितपाठस्यैव सत्त्वेन तदनुपपत्तिरूपदोषाभावादाह—त्वर्थं चेतीति ॥ शाखान्तरे 'हेलयो हेलयः' इति पाठे यत्वमपि तदिति ज्ञेयम् ॥ भाष्यकैयटसाधारण्येनाह—[११ शप०] न म्लेच्छीति । इत्येतत्-विधिवाक्यम् । म्लेच्छभाषेति । यवनभाषानिषेधेत्यर्थः ॥ सा निषेध्यत्वेन विषयो यस्येत्यर्थे तु यथाश्रुतमेव साधु ॥ 'न म्लेच्छभाषां शिक्षेत्' इति तद्विषय-

निषेधस्यातिरिक्तस्य सत्त्वादाह—[११ शप०] भ्रमेति ॥ न चैवं तस्याः स्मृतेर्मूलान्तरं कल्प्यं स्यात्, प्रमाणतया समागतस्यार्थस्य तत्कल्पनायां बाधकाभावादिति भावः ॥

[उ० १२ शप०] उद्द्योते-ह वै इतीति । निपातसमुदायो द्वौ वेत्यर्थः ॥ न चानेन वैदिकशब्दमात्रापभाषणं निषिध्यते, अर्थवादे सामान्यापभाषणानुवादेन पराभवस्योक्तत्वात् । न म्लेच्छितवा इत्यस्य म्लेच्छभाषाविषयत्वाभावे युक्त्यन्तरं ध्वनयन्नत्र हेत्वन्तरमाह—[१३ शप०] अपेति ॥

[उ० १३ शप०] एवो व्युत्क्रमे, ईषद्भ्रंशतो व्याकरणानुगतशब्दस्यैवेत्यर्थः । तथाच तेन तत्र भाषणम्, तथा न वाच्यं वेति भावः ॥

[उद्द्योते] पुरुषे देशस्यत्वादेव वृत्तेराह—[१४ शप०] वेशेति ॥ यत्तु म्लेच्छधातोरव्यक्तवाचित्वाद् अपशब्दस्य च मन्दोच्चारणबोधकत्वादव्यक्तत्वसंभवात्सामानाधिकरण्यम् । न चैवं कथं निन्द्यत्वम्, व्यक्तापेक्षयाऽव्यक्तस्य लोके निन्दितत्वात् 'अयं न स्पष्टं वदति किंत्वव्यक्तम्' इति कृष्णः । तन्न, एवं सत्यपभाषणस्योक्तरीत्याऽव्यक्तत्वेऽपि दृष्टादृष्टक्रतुवैगुण्यानापादकत्वेन निषेधस्य क्रत्वङ्गत्वासंभवापत्तेः । तदेतद् ध्वनयन्नाह—[१५ शप०] निन्द्येति । धातूनामनेकार्थत्वादिति भावः ॥ तोच्चारणेन-तद्विषयत्वेन ॥ शास्त्रबोधितत्वं तद्विपरीतत्वं चोच्चारणक्रियाया यथाकथंचिद्विशेषणं बोध्यम् ॥ एवं च-तस्य तथा पापसाधनत्वे च ॥ तथा तस्य तद्विषयत्वेन तत्साधनत्वम्, तथा तत्प्रयोक्तुः पापस्य जायमानत्वेन तथोच्चारणेन तत्साधनत्वात्तेषामपि निन्दाविषयत्वम् । तदाह—म्लेच्छा इति ॥ तत्फलप्रदर्शनमुखेनैव तेऽसुरा इत्यर्थवादः ॥ एतेन—अपशब्दस्य म्लेच्छत्वं जातिम्लेच्छकृतमन्दोच्चारणविषयतया गौणम् । तेन म्लेच्छ इति गौण्युक्तिः । तथा च यस्मादेषोऽपशब्दोऽतिप्रसिद्धो म्लेच्छस्तस्मात् तेऽसुराः देवान्प्रति तथा वक्तव्ये तथाऽपशब्दं कुर्वन्तः पराभवमापुः । तस्माद् ब्राह्मणेनापशब्दभाषणं सर्वथा वर्ज्यमित्यर्थो वाच्यः-इति कृष्णोक्तमपास्तम् । उक्तरीत्या मुख्यतयैव निर्वाहे गौणपरतया योजनाऽनौचित्यात् । तेषां तथोच्चारणनियमाभावाच्चेति दिक् ॥ ब्राह्मणेनेत्युक्तिस्तूक्ताभिप्रायैवेति बोध्यम् । तदाह—दिगिति ॥

हिंसितवानित्यर्थः । इन्द्रस्याभिचारो वृत्रेणारब्धस्तत्र 'इन्द्रशत्रुर्वर्धस्व' इति मन्त्र ऊहितः । तत्रेन्द्रस्य शमयिता शातयिता वा भव-इति क्रियाशब्दोऽत्र शत्रुशब्द आश्रितो न तु रूढिशब्दः, तदाश्रयणे हि बहुव्रीहितत्पुरुषयोरर्थाभेदः । तत्रेन्द्रामित्रत्वे सिद्धे सति 'इन्द्रस्य शत्रुर्भव' इत्यत्रार्थे प्रतिपाद्येऽन्तोदात्ते प्रयोक्तव्य आद्युदात्त ऋत्विजा प्रयुक्त इति-अर्थान्तराभिधानादिन्द्र एव वृत्रस्य शातयिता संपन्नः । इन्द्रशत्रुत्वस्य च विधेयत्वात् संबोधनविभक्तेरनुवाद्यविषयत्वाद्धिहाभावः । यथा—राजा भव युध्यस्वेति ॥ ऊह्यमानस्य चामन्त्रत्वात् 'यज्ञकर्मणि—' इति जपादिपर्युदासेन मन्त्राणामेकश्रुतिर्विधीयमाना नेह भवति ॥

[भाष्ये]—एवं वर्णापराधेऽनर्थमुक्त्वा वाक्यापराधेऽप्याह—भाष्ये—दुष्ट इति ॥ अपशब्दप्रयोगे प्रत्यवायप्रतिपादकमिदं शिक्षावाक्यम् ॥ यद्यपि तत्र 'मन्त्रो हीनः' इति पठितम्, तथाप्यत्रैतत्पाठस्य फलमग्रे स्फुटीभविष्यति ॥

[भाष्ये] स इति । स्वरादिदुष्ट इत्यर्थः ॥

[भाष्ये] तथाचैताद्दृशशक्त्विक्कृतापराधाद्यजमाननाशश्रवणेन को नामावैयाकरणमृत्विजं वृणुयादिति ऋत्विक्त्वेन द्रव्यार्जनादिकं कर्तुं व्याकरणमध्येयमिति फलितम् ॥ तदाह—दुष्टानिति भाष्ये ॥ इदं भाष्यं-शिक्षाश्रुत्यादिकं च डित्थादीनां व्युत्पन्नत्वमिति स्वीकर्तृशाकटायनादिमत इति भावः ॥

[प्रदीपे] 'स्वरेण वर्णेन वाऽन्यथाभूतो दुष्टः शब्दः प्रयुक्तो मिथ्या मृषा । कुत इत्यत आह—न तमर्थमाहेति । यदर्थ—इत्यादिकैयटोक्त एवार्थः'—इति कृष्णोक्तव्याख्याने प्रयुक्त इत्यस्य वैयर्थ्यापत्तिरध्याहारबाहुल्यापत्तिः, तस्य स्वरसतः प्रतीयमानविधेयत्वभङ्गापत्तिश्च । अत आह—[कैयटे २ यप०] मिथ्याप्रयुक्त इतीति ॥

[प्र० ३ यप०] भाष्यस्थे 'न तं' इत्यादेरर्थमाह—कैयटे—तत्तमाभिमतमिति ॥ एवं च मिथ्याप्रयुक्तत्वमत्र हेतुः । तत्तत्स्वरवर्णानुपूर्वीकमेव हि पदादि तत्तदर्थमिति तत्र तत्र प्रयुक्तं सत् तं तमर्थं बोधयति नान्यथेति भावः ॥

[प्रदीपे] 'वाग्वज्रः' इत्यत्र द्वन्द्वे निर्देशानुपपत्तिः, बहुव्रीहौ प्रकृतपरामर्शि'सः'इत्यादिना समानाधिकरण्यमनुपपन्नमत आह—[कैयटे ४ थप०] वागेवेति ॥ स वागेव सन् वज्रो भूत्वा यजमानं मारयेदित्यर्थः ॥ रूपके साधारणधर्म उपस्थितत्वात् हिंस्येवेति सूचयन्नाह—हिंसेति ॥ एतेन हिनस्तीति लेट्, न तु लट्, वर्तमानत्वानुपयोगादिति सूचितम् ॥

[प्रदीपे] तत्रेन्द्रशत्रुशब्दस्यार्थपरत्वे दृष्टान्तत्वानुपपत्तिरर्थासंगतिश्चात आह—[कैयटे ४ थप०] शब्द इति ॥ पुरा किल विश्वरूपाख्ये त्वष्टुः पुत्रे इन्द्रेण हते कुपितस्त्वष्टा इन्द्रस्य हन्तारं पुत्रान्तरमुत्पिपादयिषुराभिचारिकं यागं कृतवानित्यादि श्रुत्यादौ प्रसिद्धम् । तदाह—इन्द्रस्येति ॥

[प्र० कैयटे ५ मप०] तत्रेन्द्रेति । याग इत्यर्थः ॥

[प्रदीपे] विनिगमनाविरहादाह—[कै० ६ ष्ठप०] शातयिता भवेतीति । न्यासिद्धत्वात् ॥ 'वर्धस्व' च इत्यपि बोध्यम् ॥

(उद्द्योतः) असर्वनामत्वात्तसोऽप्राप्तेराह—स्वरेणेति । आद्यादिस्वादिति च । 'तं'इत्यस्य यच्छब्दापेक्षित्वादाह—यदर्थेति ॥ 'मिथ्याप्रयुक्तः' इत्यस्य विवरणं—ततोऽर्थान्तरमिति ॥ न केवलं तदर्थं नाह-इत्येतावत्, किंतु प्रत्यवायोत्पादनद्वारा हिंसकोऽपीत्याह—वागेवेति । यथा—अध्वर्युकृताद्धोमाद्यजमाने धर्मोत्पत्तिः, एवं तत्कृतापशब्दप्रयोगात्तस्मिन् प्रत्यवाय इत्याशयः ॥ तत्र दृष्टान्तमाह—यथेति ॥ वृत्रेणेति—हेतौ तृतीया, फलमपीह हेतुः ॥ मन्त्र इति । न चोहितस्य कथं मन्त्रत्वमिति वाच्यम् । मन्त्रशब्दस्य बोधकपरत्वात् । अत एव 'मन्त्रो हीनः स्वरतः' इति प्रसिद्धमपि शिक्षापाठं विहाय भाष्ये—'दुष्टः शब्दः' इति पठितं तत्रस्थमन्त्र-

---

शब्दोऽत्र-ऊहिते वाक्ये ॥ हि—यतः ॥ रर्थाभेद इति । अर्थभेदो न स्यादित्यर्थः ।'

[प्रदीपे] क्रियाशब्दाश्रयणे त्वर्थभेद इत्याह—तत्रेन्द्रेति [कै० ८ मप०] तत्र—ऊहितवाक्ये । प्रयोक्तव्यादावस्यान्वयः ॥ नन्विन्द्रसपत्नत्वविशिष्ट एव कुतो न विधेयोऽत आह—सिद्धे इति ॥ सतिसप्तम्या हेतुत्वं-अस्यातदर्थप्रतिपादनसूचने ॥ शत्रुः—शातयिता ॥ आद्युदात्त इति । व्युत्पत्तिपक्षे 'ऋज्रेन्द्राग्र—' इत्यादिना तस्य रन्नन्तत्वोक्त्वान्नित्वादाद्युदात्तत्वम् । सिद्धान्तमते तु 'ग्रामादीनां च' इति । तदेव च बहुव्रीहौ पूर्वपदप्रकृतिस्वरेणावतिष्ठत इति भावः ॥ [१२ शप०] [१० मप०] अर्थान्तरेति । बहुव्रीहिगम्येत्यादिः ॥ [१२ शप०] राजेति । तस्य सिद्धत्वे तु राजन् युध्यस्वेति भवत्येवेति भावः ॥

[उद्द्योते] तस इति । तसिल इत्यर्थः ॥ स्वरेणेतीति । 'इतराभ्योऽपि दृश्यन्ते' इत्युक्तेस्तृतीयार्थे इति भावः । एवं 'वर्णतः' इत्यत्रापि बोध्यम् ॥ हीनशब्दस्यापाठात् 'हीयमान—' इत्यस्याप्राप्तेराह—आद्यादीति ॥

[उ० २ यप०] तमित्यस्येति । यत्तदोर्नित्यसंबन्धादिति भावः ॥ अध्याहाराभावजलाघवमाह—मिथ्येति । 'प्रतिपादयन्' इत्यन्तमिति भावः ॥

[उ० ४ थप०] उद्द्योते—तदर्थमिति—कर्मधारयः ॥

प्रस्येति । यजमानस्येत्यादिः ॥

[उद्द्योते] नन्वन्यकृतापराधेन कथमन्यनाशः । किं चात्र नाशो न यजमानस्य किंतु तत्पुत्रस्येति वैषम्यम्, अत आह—[उ० ५ मप०] यथेति । अत्र चेदमेव वचनं मानम् । तथा च न तत्प्रातिपादने तात्पर्यम्, किंतु प्रत्यवायोत्पत्तौ । सा च स्वस्य नाशिका स्वीयस्य वा । सोऽपि स्वस्यैव नाश इति भावः ॥ [६ ष्ठप०] तत्र—हिंसायाम् ॥

[उद्द्योते] तत्र त्वष्टुः कर्तृत्वेन वृत्रेणेत्यनुपपत्तेराह—[उ० ७ मप०] वृत्रेणेतीति ॥ हेतुत्वस्यापि वस्तुतो बाधादाह—फलमिति ॥ तदप्युक्तप्रयोगहेतुत्वेन विवक्षितमित्यर्थः ॥ तथा च वृत्रोत्पत्त्यर्थं त्वष्टा स आरब्ध इत्यर्थो बोध्यः ॥

शब्दस्य शब्दमात्रपरता–इति सूचयितुम् ॥ शत्रुशब्दस्य मित्रपर्यायत्वे बहुव्रीहितत्पुरुषयोरविशेषोऽत आह—मन्त्रेन्द्रस्येति । शदेर्ण्यन्तादौणादिकः क्रुन् । प्रज्ञादिगणे निपातनाद्ध्रस्वत्वम् । शमेस्तु तत्वम् ॥ संबोधनविभक्त्यभावायाह—इन्द्रशत्रुस्त्वस्येति ॥ नन्वत्र 'यज्ञकर्मणि–' इत्येकश्रुतौ प्राप्तायां पूर्वपदप्रकृतिस्वरकरणं स्वरापराध इति वक्तुं युक्तम् । न च तथैवास्तु, शतपथब्राह्मणतद्भाष्यविरोधात् । तत्र हि आद्युदात्तत्वकरणमेव स्वरापराध उक्त इत्यादि स्पष्टमसत्कृतैकश्रुत्यवादेऽत आह—ऊह्यमानस्य चेति । तदुक्तम्—'अनाम्नातेष्वमन्त्रत्वम्' (पू० मी० २।१।३४) इति । न चास्यामन्त्रत्वे लौकिकशब्देन क्रियमाणस्य कर्मणः कथं फलजनकत्वमिति वाच्यम् । 'सूर्याय त्वा' इत्यादेर्लौकिकघटितस्य ऊहविधायकशास्त्रबलेन फलजनकत्ववदुपपत्तेरित्याहुः ॥

(भाष्यम्)

यदधीतम्—

"यदधीतमविज्ञातं निगदेनैव शब्द्यते ।
अनग्नाविव शुष्कैधो न तज्ज्वलति कर्हिचित् ॥"

[उद्द्योते] 'मन्त्रे स ऊहितः' इति दण्ड्युक्तव्याख्याऽयुक्ता, तत्र तस्य तस्याभावात्–यागे ऊहितत्वात् । तदेतद् ध्वनयन्नाह—[उ० ८ मप०] न चोहीति । सर्वस्येत्यर्थः । 'अनाम्नाता अमन्त्राः' इत्यापस्तम्बोक्तेरिति भावः ॥ यद्यपि लोके एकावयवाभिव्यक्तिविनाशयोरवयविप्रत्यभिज्ञानवदत्राप्येकावयवाभावे पदान्तरप्रक्षेपे चाध्ययनकालावगतमन्त्ररूपत्वप्रत्यभिज्ञानात्प्रक्षिप्तपदमात्रस्यैवामन्त्रत्वं न तु सर्वस्येति प्रागुक्तम्, तथाप्येकदेशोहस्थले तथा संभवेऽपि सर्वोहस्थले न संभवतीत्याशयेनाह—[८ मप०] मन्त्रेति ॥

[उ० ९मप०] अत एव–अमन्त्रत्वादेव ॥ [१०मप०] पठितमिति । व्यक्तमपीति शेषः । अन्यथा दृष्टान्तासंगतिरेव स्यादिति भावः ॥ [१० मप०] तत्रत्येति । शिक्षापाठस्येत्यर्थः ॥ शब्देति । बोधकेत्यर्थः ॥ मात्रशब्दः कार्त्स्न्ये । यद्वाऽवधारणे । [११ शप०] स्वामित्रेति । सपत्नेत्यर्थः ॥ [१२ शप०] रविशेष इति । तयोरर्थभेदो न स्यादित्यर्थः ॥ वज्रेणेति । आभिचारिकयाग इत्यर्थः ॥

[उद्द्योते] ऐच्छिकत्वादाह—[उ० १३ शप०] शमेरिति ॥ ह्रस्वमिति । प्रज्ञादिगणे निपातनादित्यस्यानुषङ्गः । प्रत्ययविधानाय प्रकृतीनां तत्रानुवादादिति भावः ॥

[उ० १४ शप०] नन्वत्रेति । ऊहिते प्रागुक्तवाक्ये–इत्यर्थः ॥ [१८ शप०] तदुक्तमिति । जैमिनिना भेदलक्षणे इति शेषः ॥ 'ऊह्यमानस्य मन्त्रत्वम्–उत न' इति संशय्य मन्त्रैकवाक्यत्वेन मध्यनिवेशान्मन्त्रत्वमिति पूर्वपक्षोक्तौ–उक्तम्—'अना—' इति । उक्तहेतोर्न तत्त्वकारणत्वं किंत्वभियुक्तप्रसिद्धेः ॥

[उ० २१ शप०] करववदिति । शिक्षावचनं श्रुत्यादिकं चात्रापि प्रमाणमिति भावः ॥

[भाष्ये] शब्द्यते–पुनःपुनरुच्चार्यते । भेर्येव तेन पुरुषेण ध्वनिमात्रमेवाभिव्यज्यत इति यावत् ॥ अनग्नाविवेति । बहुव्री-

तस्मादनर्थकं माधिगीष्महीत्यध्येयं व्याकरणम् ॥

यदधीतम् ॥

(प्रदीपः) **अविज्ञातमिति** । अविदितसुबादिसंस्कारत्वात्, अर्थापरिज्ञानाद्वा ॥ **निगदेनेति** । पाठमात्रेण ॥ **न तज्ज्वलतीति** । निष्फलं भवति ॥ **अनर्थकमिति** । निष्प्रयोजनम् ॥

(उद्द्योतः) ननु–अधीतमविज्ञातं–इति विरुद्धमत आह—**अविदितेति** ॥ **शुष्कैध इति** । सान्तक्लीबैधःशब्देनादन्तपुंलिङ्गेन वा निर्वाह्यम् ॥ निरुक्ते तु 'यद्गृहीतमविज्ञातं' इति पठ्यते । तत्र गृहीतं शब्दतः, अविज्ञातमर्थत इति बोध्यम् ॥ भाष्ये—**तस्मादनर्थकमिति** । अनेन निन्दार्थवादेन निष्प्रयोजनाध्ययनानौचित्येन निष्प्रयोजनं नाध्येयमिति निषेधकल्पनादिति भावः । अतो निषिद्धमध्ययनं मा भूदिति व्याकरणमध्येयमिति तात्पर्यम् ॥

(भाष्यम्)

यस्तु प्रयुङ्क्ते—

"यस्तु प्रयुङ्क्ते कुशलो विशेषे
शब्दान्यथावद्व्यवहारकाले ।

हिपक्षे भस्मप्रदेश इवेत्यर्थः । नञा विरोधार्थकेन तत्पुरुषे जलप्रदेश इवेत्यर्थः । प्रक्षिप्तमिति शेषः ॥

[भाष्ये] न तज्ज्वलतीति । न दीप्यते न प्रकाशते–इत्यर्थः ॥

[भाष्ये] अधीतस्य स्वरूपेणाविज्ञातत्वं न संभवतीति तदनर्थकपरमिति बोधयन्नुपसंहरति—भाष्ये—तस्मादिति ।

[प्रदीपे] कैयटे—अविदितेति बहुव्रीहिः ॥

"स्थाणुरयं भारहारः किलाभूदधीत्य वेदं न विजानाति योऽर्थम् ।"

"योऽर्थज्ञ इत्सकलं भद्रमश्नुते नाकमेति ज्ञानविधूतपाप्मा ॥"

इति श्रुतिमन्त्राद्यनुरोधेनाह—अर्थापरीति ॥

[प्रदीपे] तत्फलितमाह—कैयटे—निष्फलमिति ॥

[प्रदीपे] अनर्थकमित्यस्याभिधेयशून्यमित्यर्थनिरासायाह—कैयटे—निष्प्रयोजेति ॥ दृष्टान्तबलेनैवमेव लाभादिति भावः ॥

[उद्द्योते] विनिगमनाविरहादाह—[उ० २ यप०] अद्न्तेति ॥ इदं श्रुतिस्थमिवेति ध्वनयन्नाह—[३ यप०] निरुक्ते त्विति ॥ पाठभेदेऽप्यर्थस्य साम्यमित्याह—तत्रेति । तत्रार्पत्यर्थः ॥

[उद्द्योते] 'तस्मात्' इत्यस्याधिकस्य पूर्वत्रानुक्तस्यार्थमाह–[उ० ५ मप०] अनेनेति । 'यदधीतं' इत्यनेनेत्यर्थः । अनेन 'दुष्टः शब्दः' इत्यत्राप्येवं रीतिः सूचिता ॥

[उद्द्योते] अत एव यथाश्रुतानुपपत्तेराह—[७ मप०] अत इति । प्रकृत्यादिज्ञानेन पदादिभागार्थज्ञानेनानुष्ठाने तथा प्रागुक्तं फलमिति परमतात्पर्यम् ॥

[भाष्ये] सोऽनन्तमिति ॥ ऐहिकापेक्षयाऽतिशयितत्वमनेनोच्यते । अन्तवत्त्वं त्वस्त्येव, कर्मजन्यस्य सर्वस्यानित्यत्वात् ॥ जयमिति । उत्कर्षमित्यर्थः । लक्षणया सुविशेषमिति यावत् ॥ परत्र–परलोके ॥

[भाष्ये]—[९ मप०] ज्ञानेऽप्येति । ज्ञानेऽधर्मोऽपीत्यर्थः ॥

[भाष्ये] तादृशाधर्मप्राप्तौ हेतुमाह भाष्ये [१३ शप०]

सोऽनन्तमाप्नोति जयं परत्र
वाग्योगविद् दुष्यति चापशब्दैः ॥"

कः ?

वाग्योगविदेव ॥

कुत एतत् ?

यो हि शब्दान् जानाति, अपशब्दानप्यसौ जानाति । यथैव हि शब्दज्ञाने धर्मः, एवमपशब्दज्ञानेऽप्यधर्मः ।

अथवा भूयानधर्मः प्राप्नोति । भूयांसोऽपशब्दाः, अल्पीयांसः शब्दा इति । एकैकस्य शब्दस्य बहवोऽपभ्रंशाः । तद्यथा-गौरित्यस्य गावी गोणी गोता गोपोतलिकेत्येवमादयोऽपभ्रंशाः ।

अथ योऽवाग्योगवित्, अज्ञानं तस्य शरणम् ॥

(प्रदीपः) यस्तु प्रयुङ्क्ते इति । अनेनाभ्युदयहेतुत्वं व्याकरणाध्ययनस्य दर्शयति ॥ **विशेष इति** । स एव शब्दः क्वचिदर्थे केनचिन्निमित्तेन प्रयुक्तः साधुः, अन्यथा त्वसाधुः । यथा-अश्वे-अश्वशब्दो धनाभावनिमित्तकः साधुः, जातिनिमित्तकोऽसाधुः । गवि च गोणीशब्दः साधर्म्यात्प्रयुक्तः साधुः, जातिप्रयुक्तस्त्वसाधुः ॥ **क इति** । वाग्योगविदः श्रुतत्वाद्दोषदर्शनाच्च प्रश्नः ॥ प्रष्टैव परमतमाशङ्क्याह—**वाग्योगविदेवेति** ॥ **एवमपशब्दज्ञानेऽपीति** । यथा श्लैष्मिकद्रव्यसेवया श्लैष्मिकव्याधिसम्भवः, तद्विपरीतसेवया त्वारोग्यं; तथाऽत्रापि यथोक्तं न्याय्यमिति भावः ॥ **भूयांसोऽल्पीयांस इति** । परमतापेक्षया प्रकर्षप्रत्ययः । यदि मन्यसे-बहवः शब्दाः, अल्पेऽपशब्दाः, अतो भूयस्त्वाच्च फलभूयस्त्वमिति । तन्न । यस्माद्भूयांसोऽपशब्दाः, अल्पीयांसः शब्दाः ॥ **अज्ञानमिति** । तथा च तिरश्चां ब्रह्महत्यादिफलाभावः ॥

(उ०) 'एकः पूर्वपरयोः' इत्यत्र भाष्यपठित **'एकः शब्दः-'** इत्यादिश्रुतिमूलकमाह—(भाष्ये)—**यस्त्विति** । **अभ्युदयहेतुत्वम्**-अदृष्टद्वारा पुरुषार्थसाधनत्वम् । **कुशलः**-अधीतव्याकरणः । लक्षणस्मरणपूर्वकं यः प्रयुङ्क्ते-इति फलति ॥ **विशेष इति** । अर्थविशेष इत्यर्थः । तदाह—**स एवेति** ॥ **साधर्म्यात्**-साधर्म्यमूलकादभेदारोपात् ॥ भाष्ये—**यथावत्**-अम्बूकृतादिदोषरहितम् । वाचो योगः-प्रकृतिप्रत्ययविभागेनार्थविशेषपरत्वं, तद्वेत्तीति—**वाग्योगविद्** ॥ **श्रुतत्वादिति** । एषाम जयासिद्दोषयोश्चकारेण समुच्चयप्रतिपादनार्थेत्यपि

भूयांस इति । इतिहेतौ । **भूयांसो** ह्यपेति पाठे हि-हेतौ ॥

[भाष्ये] नन्विदानींतनव्यवहाराय संकेतितापशब्दानां कथं नित्यसुशब्देभ्यो भूयस्त्वम्, अतस्तदुपपादयति—[भा० १२ शप०] **एकैकस्येति** । देशकालपुरुषतदीयशक्तिवैकल्यानां भूयस्त्वादिति भावः ॥

[भा० १५ शप०] **अथ**शब्द आनन्तर्ये । एवमग्रेऽपि ॥ विदुष एव सर्वत्राधिकारदर्शनादाह—**अज्ञानमिति** । निषेधशास्त्राज्ञानमित्यर्थः ॥

[प्रदीपे] तदेवाह—कैयटे—**अनेनेति** । पद्येनेत्यर्थः ॥

[प्रदीपे] अत्र रत्नकृत्—अत्र स्वार्थे ईयसुन् **'अल्पाच्तरम्'** इत्यत्र तरविव ॥ एतेन कैयटोक्तं चिन्त्यम्—इति । यद्यपि आतिशायनिकप्रकरणे एव **'तादौ घः'** इत्यादौ वाच्ये गुरुसूत्रकरणस्य **'गरीयांसं यत्नम्'** इत्यादिभाष्यानुरोधाद्योगापेक्षज्ञापकत्वाङ्गीकारेणेदं समूलम्, तथापि तस्यागतिकगतित्वेन प्रकृते पूर्वपक्षिणा साधुशब्दानां बहुत्वस्यासाधुशब्दानामल्पत्वस्य प्रक्रान्तत्वेन तत्त्वण्डनेऽत्र परमतापेक्षया प्रकर्षस्य तात्पर्यविषयतया तथैवोपपत्तौ तदङ्गीकारोऽत्र युक्तः । अत एवानिष्टप्रयोगो नापाद्यः, इति तदुक्तमयुक्तमेवेति दिक् । तदभिप्रेत्याह—[कैयटे १० मप०] **परमतेति** ॥

[प्र० १२ शप०] कैयटे (भाष्यस्थ-) **'इत्येवमादि'**पदार्थमाह—**यस्मादिति** ॥ तथा च बह्वनर्थप्रतिविधानेन तदङ्गीकारेण वाऽल्पफलसाधनं प्रेक्षावतां न युक्तमन्यत्रादृष्टत्वादिति तात्पर्यम् ॥

[प्रदीपे] तस्य तदभावे दृष्टान्तमाह—[कै० १३ शप०] **यथा चेति** ॥ तस्मान्नित्याध्ययनमेवास्य युक्तम्, न तु शब्दव्युत्पादनार्थत्वं, तस्य प्रत्युतानर्थहेतुत्वादिति भावः ॥

[उद्द्योते] **एक इति** । **'एवं निषेधविधिविषयफलान्युक्त्वा काम्यविधिविषयं फलं कथयन्'** इत्यादिः ॥ **मूलकमिति** । **कात्यायनोक्तभ्राजाख्यश्लोकान्तर्गतं** पद्यमिति शेषः ॥

[उद्द्योते] प्रागुक्तैकवाक्यत्वायाह—[उ० ३ यप०] **अदृष्टेति** ॥

[४ धंप०] **अर्थविशेष इति** । शक्यलक्ष्ययोरन्यतमे इत्यर्थः ॥ एवंचैकस्मिन्नर्थे निमित्तविशेषैस्तत्साध्वसाधुत्वज्ञानं व्याकरणैकशरणम् ॥ अत एवाह हरिः—

'अर्थप्रवृत्तितत्त्वानां शब्दा एव निबन्धनम् ।
तत्त्वावबोधः शब्दानां नास्ति व्याकरणादृते ॥' इति ॥

तावताऽप्यनिर्वाहादाह—[५ मप०] **साधर्म्यमूलकेति** ॥

[उद्द्योते] वाग्योगविदित्यस्यार्थमाह—[उ० ६ छप०] **वाचो योग इति** ॥ एतेन—वाचः शब्दस्य योगं घटनां वेत्तीति तथा—इति कृष्णोक्तमपास्तम् । अर्थविशेषपुरस्कारेणैव शब्दसाधुत्वस्यानेन प्रतिपाद्यत्वेन तज्ज्ञातुरेव तत्त्वात् ॥ हेत्वन्तरमाह—[८ मप०] **एकत्रेति** । अत एवान्ययोगव्यवच्छेदक एवशब्दः प्रयुक्तो भाष्ये । तथाच तस्यैव कर्तृत्वमिति भावः । **'दोषदर्शनात्'** इति कैयटस्य वाग्योगविदोऽपशब्दज्ञानप्रयुक्तदोषदर्शनादित्यर्थो न, 'प्रयोगकृतो दोषो न ज्ञानकृतः' इत्यस्य वक्ष्यमाणत्वात्, तथा सति कोट्यन्तरानुत्थापकतया संशयस्याभावेन प्रश्नाभावापत्तेः, त्रिभिर्मिलित्वा वाग्योगविद एव कर्तृत्वापत्तेश्च । अत एव मध्ये शेषपूरणम् । तेनोक्तहेतुद्वयेनैककोट्युपस्थितिरन्येनान्यकोट्युपस्थितिः । तदाह—[९ मप०] **शास्त्रस्येति** ॥ **हेतुत्वं दोष इति** । वाग्योगविद इति बोध्यम् ॥ [१० मप०] **सामञ्जस्यमिति** । उत्तरस्य दुष्टत्वेनासिद्धान्तत्वादिति भावः ॥ [११ शप०] **दोष इति** । कर्तृत्वाङ्गीकारे तस्याधर्महेतुत्वापत्तिरूपदोष इत्यर्थः ॥ तथा च तददर्शनान्न तस्य कर्तृत्वम्, किं त्ववाग्योगविद इति भावः ॥ एवञ्च कैयटस्थस्चेन प्रश्ने सर्वेषां समुच्चयः ॥

[उ० १२ शप०] **नन्नु साध्विति** । एवं च 'यो हि' इत्यादिग्रन्थासंगतिरिति भावः ॥ दृष्टान्तसूचितमर्थमाह—[१३ शप०] **एवं चेति** । दृष्टान्तसत्त्वे चेत्यर्थः ॥ विशेषव्याह्यसंभवादाह—[१४ शप०] **यद्यदिति** ॥ यद्यपि तद्वलात्तापशब्दोद्देशेन शास्त्रप्रवृत्तिस्तथापि साधुज्ञानव्यापारेणासाधुज्ञानस्यापि नान्तरीयकतया

बोध्यम् ॥ दोषदर्शनादिति । शास्त्रस्याधर्महेतुत्वं दोष इत्यर्थः ॥ वादिप्रतिवादिपूर्वपक्षोत्तरपरतया व्याख्यानेऽसामञ्जस्यं मत्वाऽऽह—प्रष्टेवेति ॥ भाष्ये—कुत एतदिति । वाग्योगविदो दोषः कुत इत्यर्थः ॥ ननु साधुज्ञानस्य यथा धर्मजनकता शास्त्रोक्ता न तथाऽसाधुज्ञानस्याधर्मजनकता शास्त्रोक्तेत्यत आह—यथेति । एवञ्च—अपशब्दज्ञानं—अधर्मसाधनं, धर्महेतुशब्दज्ञानविरोधित्वात्; यद्यद्विरोधि तत्तद्विरोधिफलकं, यथा—श्लैष्मिकद्रव्यसेवा—इत्यनुमानं प्रमाणमिति भावः । एवं च शास्त्रस्याधर्महेतुतया तत्र प्रवृत्तिर्न स्यादिति नेदं वचो व्याकरणाध्ययनानुज्ञापकं स्यादिति तात्पर्यम् ॥ नन्वस्त्वधर्मोऽपि, तथापि धर्माधिक्यायाध्येयं व्याकरणमत आह—भाष्ये—अथवेति ॥ अङ्गभूयस्त्वादिति । अङ्गानां धर्मजनकानां भूयस्त्वादित्यर्थः । एवं च यज्ञादेः पापजनकत्वेऽप्यधिकधर्मजनकत्वाद्यथा

तत्र प्रवृत्तिस्तथा प्रकृतेऽपीति भावः ॥ अल्पीयांसः शब्दा इति । एवं च भूयोऽतिप्रक्षिप्तक्षीरवदनुपादेयं तद्विज्ञानमिति भावः ॥ नन्वेवं सामर्थ्यादवाग्योगविदेव 'दुष्यति' इत्यत्र कर्ताऽस्त्वत आह—भाष्ये—अथ योऽवाग्योगविदिति ॥

(बाधकभाष्यम्)

विषम उपन्यासः । नात्यन्तायाज्ञानं शरणं भवितुमर्हति । यो ह्यजानन् वै ब्राह्मणं हन्यात् सुरां वा पिबेत् सोऽपि मन्ये पतितः स्यात् ॥

(प्रदीपः) नात्यन्तायेति । पुरुषाणां विधिनिषेधयोरधिकारात्तत्परिज्ञाने प्रयत्नस्य न्याय्यत्वात् ॥

(उ०) अत्यन्तमित्यर्थे 'अत्यन्ताय' इति अव्ययम् । पुरुषाणामिति । मनुष्याणामित्यर्थः । तिरश्चामत्यन्तायोग्यत्वादरत्वज्ञानं

जननाद्य...थां वाजिनस्यैवैकत्रोभयोरविरोधादिति भावः ॥ तत्फलितमाह—[१६ शप०] एवं चेति ॥ तस्यानुमानप्रमाणकत्वे चेत्यर्थः ॥ [१७ शप०] नन्वस्त्वधर्मोऽपीति । तस्यैवेति भावः ॥ धर्मेति । धर्माद्येत्यर्थः ॥ तथाच नान्तरीयाल्पदोषत्वेन मुनिरस इति भावः ॥

[उद्द्योते] अङ्गत्वमुपकारकत्वमित्याशयेनाह—[१९ शप०] धर्मेति ॥ साधुशब्दानामित्यर्थः ॥ अयं न्यायः कुत्र दृष्टोऽत आह—एवंचेति । उक्तन्यायाङ्गीकारे चेत्यर्थः ॥ [२० शप०] पापेति । हिंसाकृतेत्यादिः ॥ तेनैव तत्क्षालनं फलबाहुल्यमेव चेति भावः ॥

[उद्द्योते] तत्फलितमाह—[उ० २२ शप०] एवंचेति । तथा व्यत्यये चेत्यर्थः ॥ अत्रोक्तदृष्टान्तविरुद्धदृष्टान्तमाह—भवतीति ॥ भवत्यभिचर्मपात्रेत्यर्थः ॥ यथा तदन्तर्गतत्वं क्षीरस्य तथा बह्वपशब्दव्याप्तत्वमेकस्य सुशब्दस्येति भावः ॥ [२२ शप०] तद्विति । साधुशब्देत्यर्थः ॥

[उ० २२ शप०] नन्वेवम्—वाग्योगविदोऽधर्मबाहुल्येन तद्विज्ञानस्यानुपादेयत्वेनास्य वचनस्यैतदननुज्ञापकत्वापत्तौ ॥ [२३ शप०] करोति । तस्य तत्सत्त्वेऽप्य सुतरां तत्सत्त्वादिति भावः ॥

[भाष्ये] तस्य नाज्ञानमात्रेण निस्तारः, किं तु निषेधाधिकारिताऽप्यस्तीत्याह—[भा० १ मप०] नात्यन्तायेति ॥

[भाष्ये] अत्र हेतुमाह—[भा० २ यप०] यो ह्यजानन्निति ॥

[प्रदीपे] नन्वजानतां प्रतिषिद्धानुष्ठानतश्चेद्दोषस्तर्हि तिरश्चामपि स्यादत आह [कै० १ मप०] पुरुषाणामिति ॥

[उ० १ मप०] अव्ययमिति । विभक्तिप्रतिरूपकमिति भावः ॥

[उद्द्योते] अधिकारिलक्षणे (पू० मी० ६ । १ । २ अ.) मनुष्याधिकारित्वस्य शास्त्रे व्यवस्थापितत्वात् 'पुरुषाणाम्' इत्ययुक्तमत आह [उ० २ यप०] मनुष्येति । तथा च तदेतदुपलक्षणमिति भावः ॥ मनुष्यस्य तिर्यक्साम्याभावमाह—तिरश्चामिति ॥

[उ० ४ धप०] महाननर्थ इति । स एवेत्यर्थः : एतेन स्वल्पस्याप्यर्थस्य निरासः ॥ ननु अत्यन्तायेत्यधिकम्, तदभावेनाभीष्टसिद्धेरत आह—तत्रेति । भाष्ये इत्यर्थः ॥ [उ० ५ मप०] दोषद्वयेति । 'यो ह्यजानन्' इति वक्ष्यमाणेत्यर्थः ॥ किञ्चिदज्ञानं शरणमेवेति ततो लब्धस्य फलितमाह—किंस्विति । वध्यादेरित्यस्य ब्राह्मणत्वादावन्वयः ॥

[उद्द्योते] अत्र ब्राह्मणादेर्न कर्मत्वम् । तथा सति ब्रह्महत्यादिपातित्याभावेन तदापादनासंगतेः, शास्त्राज्ञानस्यैव प्रक्रान्तत्वाच्च, अत आह—[७ मप०] निषेधेति । 'मन्ये' इति निश्चयार्थकं, पूर्वत्र 'वै' इतिवत् । तद्बललभ्यमर्थमाह—[८ मप०] पतित एवेत्यर्थ इति ॥

[भाष्ये] अथ सिद्धान्ती यथार्थोत्तरं दातुं पुनरनुवदति—[भा० १ मप०] एवं तर्हीति । तस्यान्यथा निर्वाहाभावेन दोषवत्त्वस्य सुवचत्व इत्यर्थः ॥

[भाष्ये] तदेतदाह—[भा० ६ धप०] विज्ञानमिति । शास्त्रादिज्ञानपूर्वकप्रयोगरूपमित्यर्थः ॥ अत एव 'विज्ञानम्' इत्युक्तम् । तत्र च बहुव्रीहिः । प्रयोगरूपोऽन्यपदार्थः ॥ जनकत्वं षष्ठ्यर्थः ॥ तदेतदुक्तं [कै० ३ यप०] ज्ञानपूर्वकेति । भाष्ये ज्ञानमिति पाठे तु तस्य लक्षणा बोध्या ॥

[प्र० कै० १ मप०] इत्याहेति । सिद्धान्तीति शेषः । इत्याशयेन स आहेत्यर्थः ॥

[उद्द्योते] उभयाकाङ्क्षारूपप्रकरणस्याभावादाह—[उ० १ मप०] संनिधेरिति । स्थानाख्यप्रमाणादन्यतराकाङ्क्षारूपादित्यर्थः ॥ दुष्यति च—इति चरत्वर्थे इति भावः ॥

[उद्द्योते] अथेत्यादि भाष्यं कैयटेन छायया व्याख्यातम् । तदाशयमाह—[उ० १ मप०] नन्वेवमिति । तस्य दोषकर्तृत्वाङ्गीकार इत्यर्थः ॥ वाग्योगेति । तस्याप्यपशब्दज्ञानादधर्मोऽपि स्यादित्यर्थः ॥ एवं च प्रागुक्तदोष एवेति भावः ॥ [२ यप०] एवं चेति । तस्य तदप्रयोगादौ चेत्यर्थः ॥ 'यस्तु प्रयुङ्क्ते' इत्यनेन एकः शब्द इति श्रुत्या च तत्प्रयोगेण धर्म उक्तो न ज्ञानमात्रेण । तथा चापशब्दज्ञानमात्रेण नाधर्मः, अपशब्दप्रयोगस्तु न वैयाकरणेन क्रियत एवेति तस्य सर्वदा धर्म एव, साधुप्रयोगादभ्युदयोऽपि । अन्यस्य तु तत्प्रयोगादधर्मवृद्धिरेव । तदाह—अपशब्देति ॥

[२ यप्रदीपे १ मप०] श्लोकस्यापरीति । तत्स्वरूपस्यापरीत्यर्थः । प्रागिति भावः । यद्वा तदाधारस्येत्यर्थः ॥ अत एवाह—[२ यप०] प्रातीति । विभक्त्यर्थप्रकारकेत्यादिः ॥ अस्याशाब्दत्वादाह—तात्पर्यमिति । तदाह—किं तर्हिति ॥ इत्यर्थ इति । इति फलितार्थ इत्यर्थः । अत एव—तत्र तात्पर्यादेव ॥

शरणं, मनुष्याणां तु योग्यत्वात्तैर्निषिद्धानुष्ठानवर्जनार्थमवश्यं शास्त्रं विधेयम् । अतोऽवाग्योगविदो महाननर्थ इति भावः ॥ तत्र 'नाशन्ताय' इत्यनेन शास्त्राज्ञानं नैव शरणं, दोषद्वयप्रसङ्गात् । किं तु वध्यादेर्ब्राह्मणत्वाद्यज्ञानमेव पापाल्पत्वे प्रयोजकमिति ध्वनितम् ॥ भाष्ये—यो ह्यजानन्निति । निषेधशास्त्रमजानन् ब्राह्मणत्वादिज्ञानपूर्वकं तद्वधादि कुर्यात्सोऽपि पतित एवेत्यर्थः ॥

(सिद्धान्तव्याख्याभाष्यम्)

एवं तर्हि—
सोऽनन्तमाप्नोति जयं परत्र
वाग्योगवित् दुष्यति चापशब्दैः ॥
कः ?
अवाग्योगविदेव ।
अथ यो वाग्योगवित्, विज्ञानं तस्य शरणम् ॥

(प्रदीपः) प्रकरणात्सामर्थ्यं बलीय इत्याह—**अवाग्योगविदिति** । वाग्योगवित्तूभयज्ञोऽपि शब्दान्प्रयुङ्क्ते, नापशब्दान्–इति ज्ञानपूर्वकप्रयोगादभ्युदयभाग्भवति ॥

(उद्द्योतः) **प्रकरणादिति** । संनिधेरित्यर्थः ॥ नन्वेवं वाग्योगविदोऽपशब्दज्ञानादधर्मः स्यादत आह—**वाग्योगेति** । एवञ्चापशब्दप्रयोग एवाधर्महेतुः, न ज्ञानमात्रमिति न दोष इति भावः ॥

(स्थानजिज्ञासाभाष्यम्)

क्व पुनरिदं पठितम् ?

(प्रदीपः) श्लोकस्यापरिज्ञानात्पृच्छति—**क्व पुनरिति** । प्रातिपदिकार्थप्रश्ने चात्र तात्पर्यम्, किं तदस्ति यत्रेदं पठितमित्यर्थः । अत एव 'श्लोकाः' इति प्रथमान्तेनोत्तरम् । अन्यथा 'श्लोकेषु' इति वाच्यं स्यात् ॥

(समाधानभाष्यम्)

भ्राजा नाम श्लोकाः ॥

(उद्द्योतः) 'भ्राजाः'नाम कात्यायनप्रणीताः श्लोका इत्याहुः ॥

(प्रामाण्याक्षेपभाष्यम्)

किंच भोः श्लोका अपि प्रमाणम् ?
किं चातः ?
यदि प्रमाणम्, अयमपि प्रमाणं भवितुमर्हति—
"यदुदुम्बरवर्णानां घटीनां मण्डलं महत् ॥
पीतं न गमयेत्स्वर्गं किं तत् क्रतुगतं नयेत् ॥" इति॥

(प्रदीपः) आप्तोक्तत्वापरिज्ञानादाह—**किं च भो इति** ॥ **यदुदुम्बरेति** । अयं श्लोकः सौत्रामणियागे सुरापाणस्य दुष्टत्वमुद्भावयति ॥

(उद्द्योतः) भाष्ये—**किं चात इति** । अतः प्रश्नात्किं विवक्षितमित्यर्थः ॥ **उदुम्बरं**=ताम्रम् ॥ **दुष्टत्वमिति** । इदमुपलक्षणम्–अन्यत्राप्यदुष्टत्वस्य ॥

(समाधानभाष्यम्)

प्रमत्तगीत एष तत्रभवतः । यस्त्वप्रमत्तगीतस्तत्प्रमाणम् ॥ यस्तु प्रयुङ्क्ते ॥

(प्रदीपः) **प्रमत्तगीत इति** । प्रमादेन–विप्रतिपन्नत्वेन गीत इत्यर्थः । कात्यायनोपनिबद्धभ्राजाख्यश्लोकमध्यपठितस्य त्वस्य श्लोकस्य श्रुतिरनुग्राहिकाऽस्ति—**"एकः शब्दः सुज्ञातः सुप्रयुक्तः स्वर्गे लोके कामधुग्भवति"** इति ॥

(उद्द्योतः) ननु कर्तरिक्तान्तप्रमत्तशब्दस्य गीतशब्देन समासोऽनुपपन्नः, 'तत्रभवतः' इत्यनेन साकाङ्क्षत्वादत आह—**प्रमादेनेति** । भावे क्तान्त इति भावः ॥ **विप्रतिपन्नत्वेन**=वेदविषयविप्रतिपत्त्याश्रयत्वेन । तत्त्वं स्वस्मिन्नारोप्य दैत्यनाशाय पूज्यस्यापि भगवत ईश्वरस्य तथोक्तिरिति स न प्रमाणमिति भावः ॥ [भाष्ये—

[उद्द्योते] ननूत्तरे उक्तो वस्तुत आधारपदार्थ एव कोऽत आह—[द० उ० १ मप०] **भ्राजेति** ॥

[वामे २यभा०१मप०] चः–प्रश्नसमुच्चये ॥ वेदस्मृतिशास्त्रविषयाः श्लोका अपि किं धर्माधर्मयोः प्रमाणमिति भाष्यार्थः ॥

[भाष्ये] परस्तद्वाचा "यदि प्रमाणं तर्हि अयमपीति" तदीयमभिप्रायमभिधापयितुं पृच्छति—[२ यप०] **किं चात इति** ॥

[भाष्ये] स स्वाशयमाह—[३ यप०] **यदीति**–भाष्ये ॥ **अयमपीति** । धर्ममनधिकृत्य येन केनापि पठितस्यापि प्रामाण्ये वक्ष्यमाणश्लोकस्यापीश्वरप्रणीतस्य प्रामाण्यापत्तिरिति भावः ॥

[वामे प्रदी०१ मप०] **आप्तोक्तत्वेति** । भ्राजाख्यानामित्यादिः ॥

[उद्द्योते] यत्तु—निपातसमुदायोऽयं किमित्यर्थे, श्लोकप्रामाण्ये किमनिष्टमित्यर्थः—इति कृष्णः । तन्न, तेषां प्रयोगासांगत्यापत्तेः, तत्प्रामाण्येऽनिष्टाभावाच्च । तदेतद् ध्वनयन्नाह—[उ० १ मप०] **अत इति** ॥

[द्वितीये उ० २ यप०] **ताम्रमिति** । तथा च लोहिनीनां कलशीनां विशालं मण्डलं लक्षणया तत्स्थं सुराद्रव्यं, स्वरूपतस्तस्य पानकर्मस्यायोग्यत्वात् । तत् पीतं सद् यदि पातारं स्वर्गं न गमयेत् तत् तर्हि सौत्रामणीग्रहपात्रस्थं स्वल्पं तत्–सुराद्रव्यं पीतं किं नयेत् । नेष्यत्येव । तथा च तैत्तिरीयब्राह्मणम् "ब्राह्मणं परिक्रीणीयादुच्छेषणस्य पातारं ब्राह्मणो ह्याहुत्या उच्छेषणस्य पाता यदि ब्राह्मणं न विन्देद् वल्मीकवपायामवनयेत् सैव ततः प्रायश्चित्तिः" इति ॥ एवञ्च स्वर्गसाधनत्वेन श्रुता सुराऽल्पत्वात् सम्यक् स्वर्गं नेतुमशक्ता । तस्मात्सौत्रामणीं हित्वा पानागारे एव मद्यं पातव्यमित्यर्थः ॥ तदेतदभिप्रेत्याह—[उ० २यप०] **इदमुपेति** । [उ० ३यप०] **अन्यत्रेति** च ॥ अन्यत्र–यागातिरिक्ते पानागारे तत्पानादुष्टत्वस्यापीत्यर्थः ॥ अपिना तस्यापि समुच्चयः ॥

[भाष्ये] एतन्निराचष्टे—[द० भा० १ मप०] **प्रमत्तेति** ॥

[द० भा० १मप०] 'तत्रभवतः' इति पूर्वान्वयी, नोत्तरान्वयी,

यस्त्वप्रमादेन गीतो यस्य कस्यापि तत्प्रमाणमिति प्रतिनिर्देशलिङ्गम् ॥] ननु कथं ज्ञातं 'अयमप्रमत्तगीतः' इति—अत आह—श्रुतिरनुग्राहिकेति ॥

(प्रयोजनभाष्यम्)

अविद्वांसः—

"अविद्वांसः प्रत्यभिवादे नाम्नो ये न प्लुतिं विदुः ।
कामं तेषु तु विप्रोष्य स्त्रीष्विवायमहं वदेत् ॥"
स्त्रीवन्मा भूमेत्यध्येयं व्याकरणम् ॥

अविद्वांसः ॥

(प्रदीपः) **स्त्रीष्विवेति** । प्रत्यभिवादे हि गुरुणा प्लुतः कार्यः । यस्तु प्लुतं कर्तुं न जानाति स स्त्रीवद्वक्तव्यः—अयं—अहं—इति, न तु 'अभिवादये देवदत्तोऽहम्' इत्यादिना संस्कृतेन वाक्येनेत्यर्थः ॥

(उद्द्योतः) भाष्ये—**अविद्वांस इति** । अत्र योग्यत्वाद्व्याकरणं कर्म बोध्यम् ॥ **प्रत्यभिवादे**=अभिवादानन्तरप्रयोज्ये वचने **नाम्नः**—अभिवादकनाम्नष्टेः प्लुतिं कर्तुं ये न जानन्ति तेषु **कामं**=निःशङ्कं **विप्रोष्य**=प्रवासादेत्य । यद्वा—**कामं**=विध्यनुसारमन्तरे-

'यस्तु' इत्यनेन विच्छेदात् । तथा च तत्रभवत एष श्लोकः प्रमादेन पठित इति तदर्थो बोध्यः ॥

[भाष्ये] नन्वेवं कथमस्यापि न प्रामाण्यम्, अत आह—[वामे भा० १ मप०] **यस्त्वप्रेति** ॥

[उ० प्र० १मप०] यद्यपि प्रमादश्चेतसोऽसमाधानम्, 'प्रमादोऽनवधानता' इत्युक्तेः, तथापि प्रकृते विशेषमाह—**कैयटे विप्रतीति** ॥

[द० उ० १ मप०] **कर्तरीति** । प्रमाद्यतीति प्रमत्त इति भावः ॥ [उ० २यप०] **साकाङ्क्षेति** । तथा च 'सापेक्षम्–' इति न्यायादसामर्थ्यमिति भावः ॥ **भावे क्तान्त इति** । भावे यः क्तस्तदन्त इत्यर्थः । प्रमत्तशब्द इति शेषः ॥

[उद्द्योते] अत एव तदर्थमाह—[उ० ३ यप०] **वेदेति** ॥

[उद्द्योते] ननु कोऽसौ तत्रभवान् ? यदीश्वरः, कथं तत्र विप्रतिपत्तिः ? अथान्यः, कथं तत्र पूज्यत्वं, भ्रमादिसंभवात् । अत आह—[उ० ४ थंप०] **सत्यमिति** । विप्रतिपत्त्याश्रयत्वमित्यर्थः ॥ आरोपे बीजमाह—**ईशेति** ॥ तत्रभवत इत्यस्यार्थमाह—**पूज्येत्यादि** ॥ **भगवतः**—षड्विधैश्वर्यपूर्णस्य ॥ **ईश्वरस्य**—नियन्तुः ॥

[उद्द्योते] अस्यापि पूर्ववदेवार्थ इत्याह—[उ० ६ ष्ठप०] **भाष्येयस्त्वेति** ॥ तस्यात्रासंबन्धं सूचयन्नाह—**यस्येति** ॥ **प्रतीति** । तदित्यत्रेति भावः ॥ एतेन—"अत्रापि यस्त्वप्रमादेन पठितः स तत्रभवतः प्रमाणमेव—इति कृष्णोक्तव्याख्यानम्'—'मद्यपानादिनोन्मत्तस्य वेदविरुद्धमार्गानुयायिना केनचित्प्रोक्तेन पठित इति न तस्य प्रामाण्यम्, तत्रभवतः—पूज्यस्य महर्षेः, कर्तुः शेषत्वविवक्षायां षष्ठी, न तु कृद्योगलक्षणा, 'न लोक–' इति निषेधात् अप्रमत्तगीतः—अप्रमादेन सावधानतया साधनेन गीतस्तत्प्रमाणं वेदवत्"—इति श्लोकं चापास्तम् । दोषगणस्त्वस्योक्तप्रायत्वात् । तु शब्दालाभापत्तेश्च । वस्तुस्थितेस्तथाऽसत्त्वाच्चेति दिक् ॥

[भाष्ये]—उक्तवैलक्षण्यस्तत्रनाय भाष्ये—**श्रुतौ तुशब्दः** ॥ ननु एतावता किमत आह—**स्त्रीवदिति** ॥ एतदध्ययनेन प्लुतज्ञाने तत्र तत्करणात्स्त्रीसाम्यं नेति तत्फलकमिदमध्येयम् । अन्यथा तत्साम्यं स्यादिति शाब्दोऽर्थः ॥

[प्रदीपे] **अयमित्यादि** । 'अयमहं नमामि' इति वदेत् । एतदभिनयेन कृताञ्जलिपुटस्य हृदयदेशप्रापणादभिवादनवाचित्वनेन तान्प्रीणयेत्, न तु 'अभिवादये भारद्वाजगोत्रकृष्णशर्माहं भोः' इत्यादिना नामगोत्रोच्चारणपूर्वकपादग्रहणं कुर्यादित्यर्थः ॥ यद्वा—उक्ताशयेन 'अयमहमस्मि' इत्येव वदेत्, न तु

'नमामि' इत्याद्यपि–इत्यर्थः ॥ तदेतद् ध्वनयन्नुभयसाधारण्येनाह—**कैयटे—प्रत्येत्यादिना** ॥ प्रत्यभिवादेन ह्यसौ संस्कृतोऽभिवाद्यो धर्मार्थी भवति स्वयं चाभ्युदयेन युज्यते । तेन तदनभिज्ञानामिवाद्या इति भावः ॥

[उद्द्योते २ यप०] **वचने**–आशीर्वचनवाक्ये । उपात्तस्येति शेषः ॥ यथाश्रुतानुपपत्तेः शेषपूरणेन व्याचष्टे—**टेरित्यादि** ॥ **कामं** यथेष्टम् । तत्फलितमाह—**निरिति** ॥ **विप्रोष्येत्यस्य** गत्वेतिरत्नोक्तव्याख्यानमयुक्तमुदक्षरत्वाद्, अत आह—[४ थंप०] **प्रवासादिति** ॥

[उ० ७ मप०] यत्तु '**अनुकरणं** चेति गतिसंज्ञायां गतिसमासेऽपि अनुकरणत्वादेवास्यवामीयमित्यादिवद् विभक्तेर्न लुक्'—इति कृष्णः । तदसद् इति ध्वनयन्नाह—उद्द्योते [७ मप०] **अयमिति** ॥ **आहुः**—सिद्धान्तविदः ॥ कैयटीयपाठं दूषयति [७ मप०] **अत्रेति** । '**वाक्येनेत्यर्थः**' इत्यत्र इत्यर्थः । उक्तहेतोः, मिथोविरुद्धत्वाच्चेति भावः ॥

[उ० ९ मप०] तत्फलितमाह—[९ मप०] **तद्व्यवहरणेनेति** । स्त्रीवदित्युक्त्येत्यर्थः ॥ '**शास्त्राज्ञानकृताप**' इति पाठः ॥

'**भूमेतीति भावः**' इति पाठः ॥

न च

आयुष्मान् भव सौम्येति वाच्यो विप्रोऽभिवादने ।
अकारश्चास्य नाम्नोऽन्ते वाच्यः पूर्वाक्षरः प्लुतः ॥

इति मनुस्मृतेरेव ज्ञाने नेदं फलमिति वाच्यम् । '**ऊकालोच्–**' इति लक्षितस्य तस्यैतदधीनज्ञानत्वात् ॥ न च लोकप्रसिध्यैव **त्रिमात्रः** प्लुत इति सुज्ञानम्, लोकप्रसिद्धेरपि शास्त्रमूलकत्वात्, '**प्लुङ् गतौ**' इति धातुसिद्धस्य तस्य त्रिमात्रेऽप्रसिद्धेरिति बोध्यम् ॥

[भाष्ये]—**विभक्तिं कुर्वन्तीति**–लेट् । विभक्त्यन्तं कुर्युरित्यर्थः । अत एव वचनैकवाक्यता ॥ कुत्रेत्याकाङ्क्षायामाह—**याज्ञिका इत्यादि** । पूर्ववत् ॥

[भाष्ये]—ननु किमेतावताऽत आह—**न चान्तेति**–भाष्ये ॥ च–यतः ॥ अतोऽध्येयं व्याकरणमिति शेषः ॥ विभक्त्यादिज्ञानं चैतदधीनम् ॥ याज्ञिकव्यवहारात्तज्ज्ञानम्—इति तु न, तस्याप्येतन्मूलकत्वात् । तस्यैव प्रमाणत्वे मीमांसोच्छेदापत्तेश्चेति दिक् ॥

[प्रदीपे]—आधानोत्तरमाधातुर्मध्यसंकटादौ विहितपुनराधेयेष्टाविदं—**प्रयाजा इति** समाम्नातम् । प्रयाजेषु यागेषु श्रूयमाणं सविभक्तिकत्वम् "आनर्थक्यात्तदङ्गेषु" (पू. मी. ३ । १ । १७) इति न्यायेन तदुपकारकेषु मन्त्रेष्ववतरतीति प्रयाजपदं मन्त्र-पर

वेत्यर्थः । 'अयमहम्' इत्यनुकरणस्यानितिपरत्वेऽपि कृभ्योगाभावाद्गतित्वाभावेन 'वदेत्' इत्यस्य तिङन्तत्वेन च समासाभाव इत्याहुः ॥ अत्र क्वचित् 'अयमहमिति वदेत् । अनुकरणं चानितिपरमिति गतित्वात्समासः' इति पाठो दृश्यते सोऽपपाठः ॥ भाष्ये—स्त्रीवदिति । तद्दत्करणेन सूचितशास्त्रज्ञानित्वकृतापमानप्रयुक्तदुःखभाजो मा भूमेति भावः ॥

(प्रयोजनभाष्यम्)

विभक्तिं कुर्वन्ति—

याज्ञिकाः पठन्ति—"प्रयाजाः सविभक्तिकाः कार्याः" इति । न चान्तरेण व्याकरणं प्रयाजाः सविभक्तिकाः शक्याः कर्तुम् ॥ विभक्तिं कुर्वन्ति ॥

(प्रदीपः) **प्रयाजा इति ।** प्रयाजमन्त्रा ऊह्यमानाऽग्निशब्दप्रकृतिकविभक्तियुक्ता इत्यर्थः । यथा "**समिधः समिधोऽग्ने अग्न आज्यस्य व्यन्तु**" अग्निरग्निरिति ।

(उद्द्योतः) ननु प्रकृतौ प्रयाजमन्त्राः सविभक्तिका एव पठ्यन्ते, तत्किमनेन वचनेन? इत्यत आह—**प्रयाजेति ।** ऊह्यमाना याऽग्निशब्दप्रकृतिकविभक्तिस्तद्युक्ता इत्यर्थः ॥ ननु 'अग्निशब्दप्रकृतिक' इत्यसङ्गतम् । अपूर्वविभक्तिमात्रविधाने '**न केवलः प्रत्ययः**' इति निषेधात् यत्किंचित्प्रातिपदिकप्रकृतिकाः सर्वा विभक्तयः प्रयोक्तव्या इति प्राप्नोति—इति चेत्, न । '**त्वमग्ने प्रयाजानुयाजानां पुरस्ताच्च पश्चात्**' इति मन्त्रवर्णनाग्निशब्दप्रकृतिका एव ता इत्याशयात् । तत्राग्नेर्देवताया एकत्वादेकवचनमेव । विभक्तयश्च प्रथमाद्वितीयातृतीयाषष्ठीसप्तम्य एवेति श्रौतसंप्रदायः ॥

मित्याह—कैयटे—**प्रयाजमन्त्रा इति । 'समिधोऽग्न आज्यस्य व्यन्तु'** इत्यादय इत्यर्थः ॥

[प्रदीपे]—**'न केवला-'** इति निषेधात्केवलविभक्तिविधानस्य दुर्वचत्वादाह—कैयटे—**ऊह्येति** ॥

[प्रदीपे]—तदभिप्रेत्यैव प्रयोगस्वरूपमाश्वलायनाद्युक्तं दिक्प्रदर्शनाय कैयटे आह—**यथा समिधः समिधोऽग्नेऽग्न इति** ॥

[उद्द्योते]—तदभिप्रेत्यैवाह—उद्द्योते—[१ मप०] **नन्वु प्रकृताविति ।** एवं चातिदेशेन तथैव तत्र तेषां प्राप्तिरिति विधानमनर्थकमिति भावः ॥ तदाह—**तत्किमिति** ॥

इदं च नाग्निशब्दे विशेषणम्, किंतु विशिष्टविशेषणमित्याह—उद्द्योते [२ यप०] **ऊह्यमानेति** ॥ तत्र शङ्कते—[३ यप०] **नन्वग्नीति** ॥ [४ थंप०] **अपूर्वेति** । यत इत्यादिः ॥ अनेनानर्थक्यशङ्का परिहृता ॥ दोषान्तरं सूचयन्नाह—**सर्वा इति** । तत्रार्थां समाधत्ते—**त्वमग्न इति** । यथासंख्यमन्वयः ॥ एतेन श्रुतानामेव **'समिधः'** इत्यादिषट्कविभक्तीनां स्थाने सर्वासां पर्यायेण प्रयोगः प्राप्नोतीत्याशङ्काऽपि समाहिता ॥ अत्रेदं बोध्यम्—यद्यपि **'विभक्तयो भवन्ति वाचो विधृत्यै'** इति तैत्तिरीयसंहिताविधिः । तत्रेष्टौ प्रयाजानामाग्नेयत्वसंपादनाय सर्वविभक्तयस्ततः प्राप्ताः । तत्राग्नेर्देवताया एकत्वात् द्विवचनबहुवचनयोरसंभव एव, तथा सति सर्वैकवचनानि प्राप्तानि । तथोत्तमेऽपि आदौ मध्ये चान्ते च, अस्य विधेरपि विशेषात् । तावता साहित्यस्यापि संभवात् **प्रयाजानुयाजेष्वेव विभक्तीः कुर्यादिति** तत्प्रकरणस्थब्राह्मणवाक्यमपि साधारणम् । तच्च सर्वं पुनराधेयमाग्नेयं न कार्यम्, किंतु प्रयाजानुयाजेष्वेवाग्निविषया विभक्तिः कार्या इत्यर्थकम् । तत्रानुयाजविभक्तिरूपमाश्वलायनेनोक्तम्—**देवबर्हिरग्ने वसुवने वसुधेयस्य वेतु देवो नराशंसाग्नौ वसुवने वसुधेयस्य वेत्वे**(त्वि)ति । तथा चाज्यभागौ पत्नीसंयाज्याभ्यः प्रकृतिवदेव ॥ आपस्तम्बेन त्वन्यथोक्तम्—**देवेऽग्नौ देवोऽग्निरिति** द्वयोरनुयाजयोर्विभक्तिमुक्त्वा **प्रयाजेन वषट्करोतीति** संहितास्थवाक्येन विभक्त्यन्तं तदुच्चार्यम् । प्रयाजेन याज्यया वषट्कारपूर्वं यजेदित्यर्थकेन तृतीयदोषनिरासः । तथा दोषद्वयमस्त्येव, तथापि **अग्नेऽग्नेऽग्नाधयेऽग्निनाग्नेऽग्निमग्न** इति चतुर्षु **प्रयाजेषु चतस्रो विभक्ती-र्ददाति नोत्तमे"** इति पक्षान्तरप्रतिपादकापस्तम्बेन सर्वनिरासः । तथा चोत्तमवर्जमग्निप्रकृतिकसंबुद्धिसप्तम्येकवचनतृतीयैकवचनद्वितीयैकवचनानि याज्यातः पूर्वमग्निशब्दात्पूर्वं वा प्रयोज्यानीति सिद्धम् ॥ द्वितीयैशङ्काऽप्यनेन समाहिता । तदेतदभिप्रेत्याह—[७ मप०] **तत्रेत्यादि** । तत्र—तत्रापीत्यर्थः ॥ सकलविभक्तीनामपि मध्ये इति यावत् ॥ तत्रापि संबुद्धिटाङेऽन्तानां न प्रयोगः । **'त्र्यक्षराः सन्तो द्वित्वेनावृत्त्या चतुरक्षरा भवन्ति'** इति वचनात् । संबुद्ध्यन्तस्य त्र्यक्षरत्वेऽपि द्वित्वोत्तरं पूर्वरूपे **'अग्नेऽग्ने'** इति त्र्यक्षरत्वात् । टाङेन्तयोरादित एव तत्त्वाभावाच्च ॥ तथा ङस्यन्तमपि न प्रयोज्यम्, **'न शब्दजामि पठेत् । शब्दजामि हि तद् भवति यत्पञ्चम्यन्तम्'** इति वचनात् ॥ तथा 'मात उत्तमे' इति वचनेन निषधादुत्तमप्रयाजमन्त्रे न तत्प्रयोग इत्याहुः ॥ तथा चादितश्चतुर्षु प्रयाजमन्त्रेषु अवशिष्टेषु यथाक्रममाद्ये पक्षे चतस्रो विभक्तयः संबुद्धिसप्तम्येकवचनतृतीयैकवचनद्वितीयैकवचनरूपा अग्निशब्दप्रकृतिविशिष्टास्ततः पूर्वं प्रयोज्याः इति सिद्धम् । स च प्रयोगो **ये यजामहे भूर्भुवः सुवः समिधोऽग्नेऽग्न आज्यस्य व्येतु वौषट्** इति ॥ द्वितीयपक्षे तु—**ये यजामहे भूर्भुवः सुवः समिधोऽग्नेऽग्ने आज्यस्य व्येतु वौषट्, ये यजामहे भूर्भुवः सुवः तनूनपादग्नावग्न आज्यस्य व्येतु वौषट्, ये यजामहे भूर्भुवः सुवरिडोऽग्निनाऽग्ने आज्यस्य व्येतु (वौषट्), ये यजामहे भूर्भुवः सुवर्बर्हिरग्निमग्ने आज्यस्य व्येतु वौषट्** इति । प्रकृतौ तु—'समिधोऽग्ने आज्यस्य **व्येतु तनूनपादग्न आज्यस्य व्येतु इडोऽग्न आज्यस्य व्येतु बर्हिरग्न आज्यस्य व्येतु'** इति श्रुतौ संबुद्ध्यन्ताग्निशब्दघटितमात्रपाठः ॥ छान्दोग्यब्राह्मणे तु अन्यथा विभक्तय आम्नाताः । ताश्च हरिटीकायां प्रदर्शिताः । तथा हि—**ये यजामहे समिधः समिधोऽग्नेऽग्न आज्यस्य व्येतु वौषट्, ये यजामहे नराशंसोऽग्निमग्ने आज्यस्य व्येतु वौषट्, ये यजामहे इडोऽग्निनाऽग्ने आज्यस्य व्येतु वौषट्, ये यजामहे बर्हिरग्निरग्न आज्यस्य व्येतु वौषट्** इति ॥ तत्र तनूनपात्स्थाने नराशंसः प्रवरभेदेन स्थितः ॥ तथा च कातीयसूत्रम्—**वशिष्ठशुनकवध्र्यश्वसंकृतिराजन्यवैश्यकण्वात्रिकश्यपप्रजापशुकामानां नराशंसो द्वितीयः, तनूनपादन्येषाम्'** इति ॥ आश्वलायनोऽपि पुनरा-

(प्रयोजनभाष्यम्)

यो वा इमाम्—

"यो वा इमां पदशः स्वरशोऽक्षरशो वाचं विदधाति स आर्त्विजीनो भवति" । आर्त्विजीनाः स्यामेत्यध्येयं व्याकरणम् ॥ यो वा इमाम् ॥

(प्रदीपः) पदश इति । पदं पदमिति 'संख्यैकवचनाच्च वीप्सायाम्' इति शस् ॥ स्वरश इति । स्वरः–उदात्तादिः ॥ अक्षरश इति । अक्षरं-व्यञ्जनसहितोऽच् ॥ आर्त्विजीन इति । ऋत्विजमर्हतीति–आर्त्विजीनः=यजमानः । ऋत्विक्कर्मार्हतीति–याजकोऽप्यार्त्विजीनः । 'यज्ञर्त्विग्भ्यां घखञौ' इति सूत्रेण 'यज्ञर्त्विग्भ्यां तत्कर्मार्हतीति चोपसंख्यानम्' इति वार्तिकेन च खञ् । 'विद्वान्यजेत विद्वान्याजयेत्' इति द्वयोरपि विदुषोरधिकारात् ॥

(उद्द्योतः) व्यञ्जनसहित इति । यथा "ये यजामहे–इति पञ्चाक्षरम्" इति । 'वर्णं वाऽऽहुः पूर्वसूत्रे' इति भाष्यात् वर्ण-

मात्रमित्यन्ये ॥ सकृत्प्रयुक्तार्त्विजीनशब्दस्योभयपरत्वे युक्तिमाह—विद्वानिति । वेदार्थज्ञ इत्यर्थः ॥

(प्रयोजनभाष्यम्)

चत्वारि—

"चत्वारि शृङ्गा त्रयो अस्य पादा
द्वे शीर्षे सप्त हस्तासो अस्य ।
त्रिधा बद्धो वृषभो रोरवीति
महो देवो मर्त्यां आविवेश ॥" इति ।

चत्वारि शृङ्गाणि–पदजातानि, नामाख्यातोपसर्गनिपाताश्च ॥ त्रयो अस्य पादाः–त्रयः कालाः=भूतभविष्यद्वर्तमानाः ॥ द्वे शीर्षे–द्वौ शब्दात्मानौ–नित्यः कार्यश्च ॥ सप्तहस्तासो अस्य–सप्त विभक्तयः । त्रिधा बद्धः–त्रिषु स्थानेषु बद्धः–उरसि कण्ठे शिरसीति ॥ वृषभो वर्षणात् ॥ रोरवीति=शब्दं करोति ॥

धेयप्रकरणे इत्थम्.........प्रयाजानुयाजान्विभक्तिभिर्यजेत–समिधः समिधोऽग्नेऽग्न आज्यस्य व्येतु, तनूनपादग्निमग्न आज्यस्य व्येतु, इळोऽग्निनाऽग्न आज्यस्य व्येतु, बर्हिरग्निरग्न आज्यस्य व्येतु' इति ॥ कातीयब्राह्मणे तु पुनराधेयप्रकरणे—'ये यजामहेऽग्न आज्यस्य व्येतु वौषट् ये यजामहेऽग्निनाज्यस्य व्येतु ये यजामहेऽग्निराज्यस्य व्येतु' इत्युक्तम् ॥ तत्सूत्रे तत्प्रकरणेऽप्येवम् ॥ तत्सूत्रे प्रकृते तु समिधः समिधो व्येतु तनूनपादग्न आज्यस्य व्येतु नराशंसोऽग्न आज्यस्य व्येतु इति । ... ... ॥ भारद्वाजसूत्रेऽप्येवम्—इति बोध्यम् ॥ इदं सर्वं यथासंप्रदायं......ग्रन्थादुपगन्तव्यम् ॥ तदेतन्मतद्वयं हृदि निधायाह—[८ मप०] विभक्त्यन्तेत्यादिना ॥

[भाष्ये]—भाष्ये—यो वा इमामिति । यः वै-निश्चयेन इमां–संनिहितामपरोक्षां वाचं–वेदरूपां वाणीं पदं–पदं स्वरं–स्वरम् अक्षरं–अक्षरं विदधाति–संस्करोति स आर्त्विजीनो भवतीत्यर्थः ॥

[भाष्ये]—ननु किमेतावताऽत आह—[भाष्ये]–आर्त्विजीना इति । यजमाना ऋत्विजश्चेत्यर्थः । आर्त्विजीयायां विदुषो-विहितत्वेनाविदुषोरविहितत्वेन तत्सिद्धेर्व्याकरणायत्तत्वेन व्याकरणेन वैदुष्यसिद्धौ तत्सिद्धिरिति भावः॥ तथा चैहिकामुष्मिकफललाभायाध्येयं व्याकरणमिति तत्त्वम् ॥ न चाध्यापकमातिशाय्यादितत्सत्त्वानमिति नेदं फलमिति वाच्यम् । दत्तोत्तरत्वात् ॥

[प्रदीपे]—कैयटे—शसिति । एवमुत्तरयोरपि ज्ञेयम् ॥ अक्षरशब्दस्य पृथगुक्तेरचः–स्वरान–इत्याह—उदात्तेति ॥ मध्यादिव्याप्त्ये आह—व्यञ्जनेति ॥ ह्लामप्राधान्याद्वैपरीत्यशङ्का तु न कार्या ॥

[प्रदीपे]—कैयटे [७ मप०] वार्तिकेन–तेनैव ॥ इतीति । इति श्रुतेरित्यर्थः ॥

[उद्द्योते १ मप०]—अत एवात्र मानमाह—उद्द्योते–यथेति ॥ भाष्यात्–उत्तराह्निकस्थात् ॥ मात्रशब्दः कार्त्स्न्येऽवधारणे वा ॥

[२ यभा०]—अथास्यापवर्गसाधनत्वमाह–भाष्ये–चत्वारीति ॥

[२ यभा०]—भाष्ये–शृङ्गेति । शेर्डादेशः ॥ त्रयो अस्येति । 'प्रकृत्यान्तःपादं' इति प्रकृतिभावः ॥ शीर्षे । शीर्षशब्दोऽकारान्तः क्लीबः ॥ हस्तास इत्यत्र 'आज्जसेः' इत्यसुक् ॥ महशब्दोऽकारान्तो 'घञर्थे कविधानं' इति कर्मणि कान्तः, महानित्यर्थः ॥ चतुःशृङ्गाद्यवच्छिन्नवृषभरूपता शब्दस्य प्रमीयमाणाऽपि प्रमाणबाधितेति गौण्या वृत्त्याऽबाधितार्थविषयतया व्याचष्टे—[६ यप०] चत्वारि शृङ्गाणीत्यादिना । अत एव शब्दस्य वृषभत्वेन निरूपणमिति कैयटेनोक्तम् ॥

[२ यभा०]—तत्फलितमाद्यमर्थमाह—भाष्ये—[६ यप०] चत्वारिपदजातानीति ॥

[२यभा०]—शृङ्गान्तराण्याह—भाष्ये [६यप०]—नामेति ॥

[२ यभा०]—त्रिभिः प्रकारैर्बद्ध इति वाच्ये तात्पर्यवृत्त्याऽऽह भाष्ये [१० मप०] त्रिष्विति ॥ बद्ध इति । व्यञ्जकध्वन्युत्पत्त्यावनभिव्यक्त इत्यर्थः ॥

[२ यभा०]—भाष्ये [११ शप०] वृषभः । वृषेरौणादिकोऽभच् किच्च । तदाह—वर्षणादिति ॥ इदं प्राग्वद् बोध्यम् ॥

[१ मभाष्ये]—भाष्ये [१मप०] कुत एतदिति । उक्तोऽर्थः । तस–कस्मादित्यर्थः । रोरूयमाणमर्थमाह—भाष्ये [२ यप०] महानिति ॥

[प्रदीपे]—ननु कालस्यामूर्तत्वेन कथमवयवत्त्वमत आह—कैयटे—लडादीति ॥ तथा च लडादीनां दशत्वेन त्रित्वासंभवात्तथा दुर्वचत्वेऽपि तद्द्योत्यकालस्य प्रसिद्धतरस्य त्रित्वात्तत्र विहितत्वेन लडादीन् त्रेधा विभज्य तद्द्योतकास्त्रेधा लडादयः पादा

कुत एतत् ?

रौतिः शब्दकर्मा ॥

महोदेवो मर्त्याँ आविवेशेति । महान्देवः=शब्दः, मर्त्याः-मरणधर्माणो मनुष्याः, तानाविवेश । महता देवेन नः साम्यं यथा स्यादित्यध्येयं व्याकरणम् ॥

(प्रदीपः) चत्वारीति । शब्दस्य वृषभत्वेन निरूपणम् ॥ **त्रयः काला इति ।** लडादिविषयाः ॥ **नित्यः कार्यश्चेति ।** व्यङ्ग्यव्यञ्जकभेदेन ॥ **सप्त विभक्तय इति ।** सुप इत्यर्थः ॥ केचित्तु तिङामपरिग्रहप्रसङ्गात्सह शेषेण सप्त कारकाणि विभक्तिशब्दाभिधेयानि-इति व्याचक्षते ॥ **वर्षणादिति ।** कामानां ज्ञानपूर्वकानुष्ठानफलत्वात् ॥ **महतेति ।** परेण ब्रह्मणेत्यर्थः ॥

(उद्द्योतः) चत्वारीति-ऋग्मन्त्रः ॥ **शब्दस्येति ।** शब्दशास्त्रप्रतिपाद्यस्येत्यर्थः । वृषभाकारः शब्दशास्त्रप्रतिपाद्यः शब्दो रोरवीति । महान् देवः-अन्तर्यामिरूपः शब्दो मर्त्यानाविवेश-स्वाभेदमाविष्कृतवानिति मन्त्रतात्पर्यम् । महतो देवस्य-शब्दब्रह्मणो व्याकरणशाप्यतया व्याकरणज्ञस्तदाविष्ट इव भवतीति यावत् ॥ भाष्ये-**पदजातानि**=परापश्यन्तीमध्यमावैखरीरूपाणि । अत एवाग्रे 'निपाताश्च' इति चकारः संगच्छते ॥ **नामाख्यातेति ।** नामशब्देन सुबन्तं, नमति=आख्यातार्थं प्रति विशेषणीभवतीति व्युत्पत्तेः । **आख्यातं-**तिङन्तम् । उपसर्गनिपातयोः पृथगुपादानं गोबलीवर्दन्यायेन ॥ **व्यङ्ग्यः-**आन्तरः । व्यञ्जकः-वैखरीरूपः ॥ तिङ्विभक्तीनां षट्त्वादाह—**सुप इति ॥ सह शेषेणेति ।** शेषः-षष्ठ्यर्थः, तत्सहितकारकाभिधायकत्वेन सुप्तिङोरुभयोरपि संग्रह इति भावः ॥ भाष्ये—**उरसीत्यादि ।**

'हकारं पञ्चमैर्युक्तमन्तस्थाभिश्च संयुतम् ।
उरस्यं तं विजानीयात् ।'

'मूर्धन्या ऋटुरषाः'

इत्यर्थः ॥ तेषामप्रयोगेऽपि तदादेशानां तत्संज्ञकानां प्रयोगसमवायात् ॥ एतेन 'कालस्यैकत्वादवान्तरभेदेनाधिक्याच्चेदं चिन्त्यम्' इत्यपास्तम् । उक्तहेतोः, तावतैव प्रसिद्धतरेण सर्वेषां ग्रहणे सिद्धेऽवान्तरभेदग्रहणे मानाभावाच्च ॥ यत्तु—"शब्दस्यात्मानौ 'ममायमात्मा' इत्यादाविवाभ्यर्हितत्वेन प्राधान्यमात्मशब्देनोच्यते स्वरूपत्वेन च प्राधान्यम् । तेन द्वौ शब्दौ व्यञ्जकौ स्फोटनादौ शीर्षे । केचित्तु—शब्दस्यात्मानौ वाच्यतया प्रधानभूतावर्थौ जातिव्यक्ती—इत्याहुः"—इति कृष्णः ॥ तन्न—इति ध्वनयन्नाह—कैयटे—[३ यप०] **व्यङ्ग्येति ॥**

[४ धंप०]—कैयटे **केचित्त्विति ।** अत्रारुचिबीजं तु त्रयः काला इत्यनेनैव तेषां संग्रहः, अन्यथा······ ॥

[उद्द्योते]—प्रसिद्धशब्दस्य तादृशशृङ्गाद्यवयवकत्वासंभवादाह—उद्द्योते—**शब्दशास्त्रेति ।** शब्दब्रह्मण इत्यर्थः ॥ 'स मर्त्यानाविवेशेत्याश्चर्यमत्र प्रतिपाद्यम्' इति रत्नकृदुक्तस्यासांगत्यं ध्वनयन्नादौ मन्त्रतात्पर्यार्थमाह—[२ यप०] **वृषभेति ॥ शब्द इति ।** शब्दब्रह्मरूप इत्यर्थः ॥ रोरवीति-शब्दं करोति, किमित्यत आह—[३ यप०] **महानिति ॥** वक्ष्यमाणभाष्यानुरोधेनाह—**स्वाभेदमिति ।** तेष्विति भावः ॥ नन्वेतावताऽपि प्रकृते किमत आह—[४ धंप०] **महत इति ॥** अभेदस्य प्रतिपाद्यत्वादाह [५ मप०] **इवेति ॥** यद्वा यथाकथंचिद्व्याकरणज्ञस्य तदाविष्टत्वाभावादाह—**इवेति ॥**

[उद्द्योते]—'पदजातान्येव दर्शयति—**नामेत्यादि'** इति दण्डिकृष्णाद्युक्त्यसांगत्यायाह—उद्द्योते [६ छप०] **परेति ॥** तद्बीजमाह—**अत एवेति ॥**

[उद्द्योते]—विविक्तं तदर्थमाह—उद्द्योते [७ मप०] **नामेति ॥ व्युत्पत्तेरिति ।** सा च स्वार्थद्वारा सुबन्तस्यैवेति भावः ॥ **आख्यातं-**तच्छब्दप्रतिपाद्यम् ॥ निपातेनोपसर्गग्रहणस्य सिद्धत्वादाह—[९ मप०] **उपसेति ॥ गोबलीति ।** इदं च कैयटादिरीत्या । सिद्धान्ते तु ब्राह्मणवसिष्ठेति बोध्यम् ॥ तथा चाद्येन धात्वर्थद्योतकैः सर्वा······अन्त्येन वाचकं त इति भेदः ॥ एतेन—'आख्यातशब्देनोपसर्गग्रहणात् तेन कर्मप्रवचनीयग्रहणम्'—इति कृष्णोक्तमपास्तम् । तेषामपि तद्विशेषद्योतकत्वेन तेनैवान्यवद्ग्रहणसंभवात् । पृथक्प्रयोगाभावेऽप्याख्यातान्तर्भावासंभवाच्च ॥

[उद्द्योते]—केचिन्मतरीत्या कैयटयोजनानिरासाय तद्व्याचष्टे—उद्द्योते—[१० मप०] **आन्तर इति ।** मध्यमावस्थ इत्यर्थः ॥ [११ शप०] **षट्त्वादिति ।** त्रिकाणामित्यादिः । **'त्रयः कालाः'**इत्यनेन तेषां संग्रहश्चेत्यपि बोध्यम् ॥ **सुप इतीति । 'स्वौजस्-'** इत्यादिप्रथमादित्रिकरूपा इत्यर्थः ॥

[उद्द्योते] एवं च न वैरूप्यं नापि काचनानुपपत्तिरिति कैयटादयश्चिन्त्या एवेति बोध्यम् । तदेतद्ध्वनयन्नाह—उद्द्योते [१२ शप०] **इति भाव इति ।** अत एव **'षट्त्वात्'** इत्येव हेतुः पूर्वमुक्तः ॥ आदाने यथा हस्तस्य व्यापारः, तथा प्रातिपदिकार्थाभिधाने विभक्तिव्यापार इति तासां हस्तत्वमिति भावः ॥

[उद्द्योते]—ननूरसो न स्थानत्वं कण्ठादिवद्बहिर्भावाद्‌त आह—उद्द्योते [१४ शप०] **हकारमिति ॥** यत्तु रत्नकृत्—अनुस्वारयमानां नासिकारूपं शिरः स्थानम्—इति । तन्न, तयोर्भेदस्य स्पष्टत्वात् । तद्ध्वनयन्नाह—**स्युर्मूर्धन्या इति ॥** अयं चाग्रे हेतुः ॥

[उद्द्योते]—एवेनान्यनासिकादिव्यावृत्तिः ॥ न्यूनतां परिहरति—**कण्ठ इति ॥** उद्द्योते [१७ शप०] **इत्युच्यत इति ।** लोके इति शेषः ॥ **वृषं-**वृषभः । तत्त्वस्याभावात् । तथाच ज्ञानपूर्वकप्रयोगेण फलस्य कामस्य सकलस्य वर्षणादिति भाष्यार्थो बोध्यः । तदाह—उद्द्योते [१८ शप०] **मेघ इति ॥** इवशब्दोत्तरम् **"अयं शब्दरूपो वृषभः सर्वान् कामान् वर्षति"** इति शेषः ॥ अत्र हेतुं प्रतिपादयन् कैयटार्थमाह—**वोक्तेति ॥** एवं च वृषभस्यातिशयः ॥ **कामानां-**स्वर्गमोक्षादीनाम् । एतावतैवास्य कामवर्षकत्वम् ॥ अतिशयवैशिष्ट्यादेव ततोऽस्य वैलक्षण्यमाह—**द्विगुणेति ॥** अग्रिमयोः करत्वेन ग्रहणात् **'द्विपात्'** इत्युक्तम् ॥

[उद्द्योते]—तदर्थमाह उद्द्योते [२१ शप०] **महानिति ।** एतेनाविष्टः सन् शब्दान् करोतीति मन्त्रार्थः ॥ न च शब्दस्य शब्दे कथं कर्तृत्वम् । न वाय्वादिशब्दाभिप्रायेण तत्, अनित्यताप्तेरिति **वाच्यम्** । तेनैव क्रियाविशेषस्य लक्ष्यत्वेन शब्दो ध्वनिः स्वव्यञ्जकमपेक्षत इत्यर्थसंभवादिति तथाङ्गीकाराच्च ॥ यद्वा-परादिषु पूर्वस्याः परत्र कर्तृत्वम् ॥ [२३ शप०] **फलमाहेति ।** तत्फलं सूचयन् एतावता प्रकृते किमायातम्-तदाहेत्यर्थः ॥ **महता देवेनेतीति ।** शब्दब्रह्मणेत्यर्थः ॥ यत्तु—साम्यम्-अवैकल्यं पूर्णतेति यावत्—इति रत्नकृत् । तन्न—इति

इत्युक्तेर्मूर्धैव शिरः ॥ 'कण्ठे' इत्यनेन मुखान्तर्गतकण्ठादिस्थानमुपलक्ष्यति ॥ ननु वर्षति=मूत्रेण भूमिं सिञ्चतीति-वृषभ इत्युच्यते, तत्कथं शब्द एवम्? इत्यत आह—कामानामिति । मेघ उदकमिवोक्तचतुःशृङ्गत्वादिगुणवैशिष्ट्येन ज्ञानपूर्वकं प्रयोगेण कामानां दानादित्यर्थः । द्विश्रृङ्गद्विपाद्विकरकण्ठमात्रवद्लौकिकवृषभादस्य व्यतिरेकः ॥ किं रोरवीति, तत्राह—भाष्ये-महान् देव इत्यादि । महान्-परब्रह्मस्वरूपो देवः=अन्तर्यामिरूपः शब्दो मर्त्येष्वाविष्ट इत्यर्थः । तदावेशफलमाह—महता देवेनेति । साम्यं=सायुज्यम् । तदुक्तं हरिणा—

अपि प्रयोक्तुरात्मानं शब्दमन्तरवस्थितम् ।
प्राहुर्महान्तमृषभं येन सायुज्यमिष्यते ॥

"आह च—चत्वारि शृङ्गा त्रयो अस्य पादा इत्यादि ऋग्मन्त्रः । इह द्वौ शब्दात्मानौ-कार्यो नित्यश्च । तत्रान्त्यः सर्वेश्वरः सर्वशक्तिर्महान् शब्दवृषभः, तस्मिन् खलु वाग्योगवित् शास्त्रशब्दज्ञानपूर्वकं प्रयोगेण क्षीणपापः पुरुषो विच्छिन्नाहंकारग्रन्थीन् अत्यन्तं संसृज्यते" इति तदर्थं तद्व्याख्यातारः ॥

(भाष्यम्)

अपर आह—

"चत्वारि वाक्परिमिता पदानि
तानि विदुर्ब्राह्मणा ये मनीषिणः ।
गुहा त्रीणि निहिता नेङ्गयन्ति
तुरीयं वाचो मनुष्या वदन्ति ॥"

'चत्वारि वाक्परिमिता पदानि' चत्वारि पदजातानि-नामाख्यातोपसर्गनिपाताश्च ॥ 'तानि विदुर्ब्राह्मणा ये मनीषिणः ।' मनस ईषिणः-मनीषिणः ॥ 'गुहा त्रीणि निहिता नेङ्गयन्ति' गुहायां त्रीणि निहितानि नेङ्गयन्ति=न चेष्टन्ते, न निमिषन्तीत्यर्थः ॥ 'तुरीयं वाचो मनुष्या वदन्ति ॥' तुरीयं वा एतद्वाचो यन्मनुष्येषु वर्तते । चतुर्थमित्यर्थः ॥ चत्वारि ॥

(प्रदीपः) 'चत्वारि' इत्यनेनैकदेशेन सदृशेन वाक्यान्तरमपि सूच्यत इत्याह—अपर आहेति । परिमितानि-इति प्राप्ते 'शेश्छन्दसि बहुलम्' इति शेर्लोपे परिमिता-इति भवति । परि-

---

ध्वनयन्नाह—सायुज्यमिति । ऐक्यमित्यर्थः ॥ इदमेव ध्वनयन्नत्र संमतिमाह—तदुक्तमिति । [२६ शप०] 'मिष्यते इति ॥' इति पाठः ॥ तद्व्याख्यातृग्रन्थमाह—[२७ शप०] आह चेति ॥ उक्तमर्थमाह—[२८ शप०] इहेति । मन्त्र इत्यर्थः । प्रतिपाद्याविति शेषः ॥ कार्यः-व्यञ्जको वैखरीरूपः ॥ नित्यः-व्यङ्ग्य आन्तरो मध्यमात्मकः ॥ अयं चाविद्यावृतत्वेन घटस्थितदीप इव नानाविध्यान् भासयन्… … … … … … … … … … …

…तदाह—सर्वेश्वर इत्यादि ॥ [२९ शप०] तस्मिन्नित्यस्य संसृज्यत इत्यत्रान्वयः ॥ वाग्योगविद्-उक्तलक्षणो वैयाकरणः ॥

[भाष्ये]—ईषन्ति ते-ईषिणः, औणादिक इनिः कर्तरि । शकन्ध्वादित्वात्पररूपम् । मनस इति कर्मणि षष्ठी ॥ 'सुप्यजातौ-' इत्यस्य तु न प्राप्तिः, मनःशब्दस्य जातिवाचकत्वात् । तदेतदभिप्रेत्याह—भाष्ये [८ मप०]—मनस ईषिण इति ॥ अन्यथा मन ईषन्ति ते-मनीषिण इत्युक्तं स्यात् ॥

[भाष्ये]—भाष्ये [९ मप०]—निहितेति । परिमितेतिवत् । नेङ्गयन्तीत्यत्र हेतुरयम् । यतो गुहायां त्रीणि परादीनि त्रिभिरेभिरवच्छिन्नानि च नामादीनि पदानि निहितानि अतो नेङ्गयन्ति, अस्यैव व्याख्यानं 'न चेष्टन्ते' इति, अस्य न प्रकाशन्त इत्यर्थः ॥ [१० मप०] न निमिषन्तीत्यर्थ इति । स्फुटप्रतिपत्त्यर्थमनेकपर्यायोपादानम् ॥

[भाष्ये]—नन्वेवं कथं मनुष्याणामवैयाकरणानां शब्देन व्यवहारोऽत आह—भाष्ये [११ शप०]—तुरीयमिति । वाचः परादेर्नामादेश्च प्रत्येकं तुरीयं चतुर्थं भागं वैयाकरणतोऽन्ये मनुष्या वदन्तीत्यर्थः ॥

[भाष्ये]—नन्वनादिलौकिकवैदिकव्यवहारे कथं भागत्रयोत्सादोऽत आह—भाष्ये [११ शप०] तुरीयमिति ॥ तदर्थमाह—[१२ शप०] चतुर्थमिति ॥ ह वै इति प्रसिद्धौ ॥ वै इत्येव पाठे वैशब्दो निश्चये ॥

[प्रदीपे]—कैयटे [१ मप०] नैकदेशेनेति । प्रतीकग्रहणकाल उक्तेनेत्यर्थः ॥ तत्सूचने बीजमाह—सदृशेनेति ॥ वाक्यान्तरमिति । एवंच प्रतिपाद्यभेदाद्वक्तृभेदेन व्यपदेश

इत्याशयेन 'अपर आह' इत्युक्तमिति भावः ॥ वस्तुतस्तु प्रोक्तमन्त्रस्य यथादावश्रिविषयत्वेनान्यत्र वर्णितत्वात् केनचिच्छिष्येणोक्ते मन्त्रे भगवता व्याख्याते छात्रान्तर्गतेनान्येनासंदिग्धवाग्विषयमन्त्रे उक्ते तं व्याख्यातुमाह—'अपर आह' इतीति बोध्यम् ॥ भगवतो वाऽन्यमतत्वेनोक्तिरित्यपरे ॥

[प्रदीपे]—कैयटे [५ मप०] इत्याहेति । इत्यतस्तत्र हेतुमाहेत्यर्थः ॥

[प्रदीपे]—गुहापदार्थमाह कैयटे [६ मप०] अज्ञानमेवेति । शास्त्राव्यवधानमपीत्यर्थः । एवोऽप्यर्थः । अत एव 'गुहा अज्ञानं हृदयादिरूपा च' इत्युद्द्योत उक्तम् ॥ गुहायामिति प्राप्ते आह—सुपामिति ॥ तेषां वेदने हेतुमाह—व्याकेति ॥

[प्रदीपे]—तदाह—कैयटे [७ मप०] तत्रेति । तेषामित्यर्थः ॥

[उद्द्योते]—वागिति 'सुपां सुलुक्-' इति षष्ठ्यन्तमित्याशयेनाह—कैयटे—परिमितेत्यादि ॥ कृष्णोऽप्येवम् ॥ तदसत्, न्यायेनैव निर्वाहे तत्कल्पनानौचित्यात् इति ध्वनयन्नाह उद्द्योते—वाक्परीति ॥ तथाच वाचः-शब्दस्य परिमितानि-परिच्छिन्नानि एतावन्त्येव पदानि सन्ति तान्येव विदन्तीत्यर्थो बोध्यः ॥

[उद्द्योते]—प्राग्वत् कृष्णाद्युक्तेरसांगत्याय चत्वारि वाक्परिमिता पदानीत्यस्यार्थस्य भाष्योक्तमर्थमाह उद्द्योते—[२ यप०] परेति ॥ चत्वारि वाक्परिमिता पदानीत्यस्य द्वितीयार्थं भाष्योक्तं विशेषं वक्तुमनुवदति—नामादीनि चेति ॥ चरमपादानुरोधेनाह—नामादीनां मध्ये चेति ॥ चतुष्पादमिति । परादिभिरेवेति भावः ॥ ये ब्राह्मणा मनीषिणश्च ते तानि सर्वाणि पदजातानि विदन्ति प्रवचनावृत्त्या पारगमनस्य वर्णान्तरेष्वभावात् ब्राह्मणा इत्युक्तम् ॥ यद्वा—वेदाख्यं ब्रह्म साङ्गोपाङ्गं विदन्तीति ब्राह्मणाः । 'ब्राह्मोऽजातौ' इति टिलोपाभावश्छान्दसः ॥

[उद्द्योते]—अत एव तथैव व्याचष्टे उद्द्योते—[४ यप०]

मितानि=परिच्छिन्नानि, एतावन्त्येवेत्यर्थः ॥ मनीषिशब्दः **पृषोदरादित्वात्साधुः** ॥ कथं मनीषिण एव विदन्तीत्याह—**गुहेति** । अज्ञानमेव गुहा, तस्यामित्यर्थः । '**सुपां सुलुक्**–' इति सप्तम्या लुक्, व्याकरणप्रदीपेन तु तानि प्रकाशन्ते । तत्र चतुर्णां पदजातानामेकैकस्य चतुर्थं भागं मनुष्याः=अवैयाकरणा वदन्ति । **नेङ्गयन्तीत्यस्यैव** व्याख्यानं न चेष्टन्ते, न निमिषन्तीति ॥

(उद्द्योतः) एतावन्त्येवेति । वाक्परिमितानीति षष्ठीतत्पुरुषः । **पदजातानि**–परापश्यन्तीमध्यमावैखर्यः, नामादीनि च । नामादिमध्ये च एकैकं चतुष्पादम् ॥ भाष्ये—**मनस ईषिणः**–चित्तशुद्धिक्रमेण वशीकर्तारः, विषयान्तरेभ्यो व्यावृत्त्या हिंसका वा । ते च वैयाकरणाः ॥ अन्येषां तदज्ञाने हेतुमाह—**गुहेति** । **एकैकस्य**–नामादिरूपस्य चतुर्थं भागम्, एकैकस्य चतुरंशत्वात् । परादीनां वा त्रयोंऽशा मध्यमान्ताः । गुहा–अज्ञानं, हृदयादिरूपा च । वैयाकरणस्तु शास्त्रबलेन–तद्बललब्धयोगेन च गुहाऽन्धकारं विदार्य सर्वं जानातीति भावः ॥ **न निमिषन्तीति**–ज्ञानसामान्यविषयत्वाभाव उच्यते ॥ भाष्ये—**यन्मनुष्येषु वर्तते**–ज्ञानविषयतया तत् वाचश्चतुर्थमित्यन्वयः । तस्मात्सकलपदज्ञानाय मनीषित्वाय वाऽध्येयं व्याकरणमिति शेषः । हरिरप्याह—

चिषेति ॥ '**ईष** ऐश्वर्ये' इत्यस्य रूपमित्याशयेनाह—**वशीति** ॥ **ईष** गतिहिंसादर्शनेष्वित्यस्य रूपमित्याशयेनाह—**विषेति** । मुख्यहिंसाया असंभवादिति भावः ॥ ते नान्ये न-इत्याह—**ते चेति** । वैयाकरणा एवेत्यर्थः । वक्ष्यमाणहेतोरिति भावः ॥ अत एवाह—**अन्येषामिति** ॥ अयं च कैयटीयैवकारसूचितोऽर्थः ॥ **मनीषिशब्दः पृषोदरादित्वात्साधुरिति** कैयटस्तु 'शकन्ध्वादित्वं नैव कल्प्यम्, कल्पनायां वाऽविशेषः' इत्याशयकः ॥

[उद्द्योते]—एवं द्वितीयव्याख्यानाशयेनोक्ते कैयटे न्यूनतां परिहरन् **पदानीत्यस्याद्यव्याख्यानाशयेनाह—उद्द्योते** [७ मप०] **परेति** ॥ एवंच तासां मध्ये चतुर्थभागं वैखर्याख्यं मनुष्या वदन्तीत्यर्थः ॥ [७ मप०] **आदिना** नाम्याधारयोर्ग्रहणम् ॥ तेषां वेदने कैयटोक्तहेतुं विशदयति—**वैयेति** ॥ नामादिपक्षे आह—**शास्त्रेति** ॥ परादिपक्षे आह—**तद्बलेति** ॥ **गुहाऽन्धेति** ॥ अज्ञानान्धकारं हृदयाद्यन्धकारं चेत्यर्थः ॥ ननु '**न निमिषन्ति**' इत्यस्य कथं तद्व्याख्यानमर्थभेदादत आह—[९ मप०] **ज्ञानेति** । धातूनामनेकार्थत्वादिति भावः ॥

[उद्द्योते]—तस्याकाशवृत्तित्वेन मनुष्यावृत्तित्वादाह—उद्द्योते [१० मप०] **ज्ञानेति** । प्रतिपुरुषं व्यवहारसाधनत्वेन तेषु तद्वर्तते तत्तुरीयम् । नानादेशेषु नानाशाखासु च कथं कथमपि विप्रकीर्णाञ्छब्दानन्विष्यापि तुर्यभाग एव ज्ञायते नान्य इति प्रतिपुरुषसमवेताज्ञानविषयत्वोक्तौ नानादिव्यवहारविरोधः ॥ भाष्ये न्यूनतां परिहरति उद्द्योते [११ मप०] **तस्मादिति** ॥ नामादिपक्षे आह—**सकलेति** ॥ परादिपक्षे आह—**मनीति** ॥ '**व च**' इति पाठः ॥ '**वा**' इति पाठे स समुच्चये ॥ अत्रैव संमतिमाह—[१२ मप०] **हरिरिति** ॥ **एतद्**–व्याकरणम् । अन्यतो विशेषादाह—**अद्भुतमिति** । तस्या वाच **एतद्**–व्याकरणमद्भुतं **परम्**–उत्कृष्टं **पदं**–स्थानमित्यन्वयः । '**पदम्** ॥ **द्युति**' इति पाठः ॥ सव्याख्यातग्रन्थमाह—[१५ मप०] **तत्रेति** । तासां मध्य इत्यर्थः ॥ **श्रोत्रेति** । स्व–परान्यतदीयेत्यादिः । मध्यमैव त्वास्यपर्यन्तं गच्छता तेन वायुना कण्ठदेशं गत्वा मूर्धानमाहत्य परावृत्य तत्तत्स्थानेष्वभिव्यक्ता परश्रोत्रेणापि ग्रहणयोग्या विराडधिदैवत्या **वैखरी** वागित्यर्थः ॥ प्रणव एव ध्यानोत्ता नाभ्यां सह वैखरीरूपं प्रतिपद्यते इति यावत् ॥ एवं च वाय्वादिपरिणामरूपा कण्ठताल्वाद्यभिघातजन्यैव ॥ अत एव—

'**वायोरणूनां ज्ञानस्य शब्दत्वापत्तिरिष्यते ।**
कैश्चिद्दर्शनभेदोऽत्र प्रवादेष्वनवस्थितः ॥'

इति हरिः ॥ **वायोः**–प्राणादिरूपस्य । **अणूनां**–शब्दतन्मात्रपरमाणूनाम्,

'**अभ्राणीव प्रचीयन्ते शब्दाख्याः परमाणवः ।**' इति तदुक्तेः ॥

ज्ञानस्य वक्तृज्ञानस्य, पराशक्तित्वादित्येन च तत्तत्परिणाम इति बोध्यम् ॥ **कैश्चिदित्यनेन** पराशक्तेरेव मध्यमावत् परिणामविशेषोऽन्येषां मते वैखरीति सूचितम् । तदाह—**प्रवादेषु**–शास्त्रेषु ॥ **अत्र** विषये **दर्शनभेदः**–सिद्धान्तभेदोऽनवस्थित इत्यर्थः ॥ [उ० १५ शप०] **मध्यमेति** । पश्यन्त्येव हृदयपर्यन्तमागच्छता तेन वायुना हृदयदेशेऽभिव्यक्ता तत्तदर्थविशेषतत्तच्छब्दविशेषोल्लेखिन्या बुद्ध्या विषयीकृता हिरण्यगर्भदैवत्या परश्रोत्रग्रहणायोग्यत्वेन सूक्ष्मा **मध्यमा** वागित्यर्थः । स्वयं कर्णपिधाने सूक्ष्मतरवाय्वभिघातेनोपांशुशब्दप्रयोगे च श्रूयमाणेयम् ॥ अस्या व्यवहारोपयोगित्वमाह—**पदेति** ॥ [उ० १६ शप०] **पश्यन्तीति** । पराख्यमेव नाभिपर्यन्तमागच्छता तेन वायुनाऽभिव्यक्तं मनोविषयः **पश्यन्ती** वागित्यर्थः ॥ इयं सूक्ष्मतरा ईश्वराधिदैवत्या योगिनां समाधौ सविकल्पकज्ञानविषय इति भावः ॥ तत्र तद्भावे हेतुमाह—**स्वरूपेति** ॥

'**वैखरी शब्दनिष्पत्तिर्मध्यमा श्रुतिगोचरा ।**
आन्तरार्था च पश्यन्ती सूक्ष्मा वागनपायिनी ॥'

इत्यप्युक्तम् । **आन्तरं** स्वरूपज्योतिरेव । **सूक्ष्मा** सूक्ष्मतरेति तदर्थः ॥ [उ० २० शप०] **मधीति** । लौकिक इति भावः ॥ अयं भावः—विन्दोः शब्दब्रह्मापरनामधेयं वर्णादिविशेषरहितं ज्ञानप्रधानं सृष्ट्युपयोग्यवस्थाविशेषरूपं चेतनमिश्रं नादमात्रमुत्पद्यते । एतज्जगदुपादानं रवादिशब्दव्यवहार्यम् । एतत्सर्वगतमपि प्राणिनां मूलाधारे संस्कृतपवनचलनेनाभिव्यज्यते ॥ ज्ञातमर्थं विवक्षोः पुंस इच्छया जातेन प्रयत्नेन योग एव मूलाधारस्थपवनस्य संस्कारः । तदभिव्यक्तं शब्दब्रह्म स्वप्रतिष्ठतया निस्पन्दं **परा** वाक् । इयं सूक्ष्मतया योगिनां समाधौ निर्विकल्पकज्ञानविषयः ॥ तदुक्तम्—

'**अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम् ।**
विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः ॥'

श्रुतिश्च—"**वागेवार्थं पश्यन्ती वागजीवीति वागर्थं निहितं संतनोति वाचैव विश्वं बहुरूपं निबद्धं तदेकस्मादेकं प्रविभज्योपभुङ्क्ते**" इति ॥ एतदवस्थात्रयमपि सूक्ष्मतमसूक्ष्मतरसूक्ष्मगुणवरूपम् ॥ [२१ शप०] **अनेकेति** । अनेके तीर्थतः शास्त्रतो भेदा यस्या इत्यर्थः ॥ **आदिभ्याम्**—उपसर्गनिपातापभ्रष्टभेरीशब्दादिरूपसंग्रहः ॥ भागवतेऽप्युक्तम्—

'**स एव जीवो विवरप्रसूतिः प्राणेन घोषेण गुहां प्रविष्टः ।**
मनोमयं सूक्ष्ममपेत्य रूपं मात्रा स्वरा वर्ण इति स्थविष्ठः ॥'

वैखर्या मध्यमायाश्च पश्यन्त्याश्चैतदद्भुतम् ।
अनेकतीर्थभेदायास्त्रय्या वाचः परं पदम् ॥

तत्र श्रोत्रविषया वैखरी । मध्यमा हृदयदेशस्था पदादिप्रत्यक्षानुपपत्त्या व्यवहारकारणम् । पश्यन्ती तु लोकव्यवहारातीता । योगिनां तु तत्रापि प्रकृतिप्रत्ययविभागावगतिरस्ति । परायां तु नेति त्रय्या इत्युक्तम्,

"स्वरूपज्योतिरेवान्तः परा वागनपायिनी ।
तस्यां दृष्टस्वरूपायामधिकारो निवर्तते ॥" इत्युक्तेः ।

अनेकतीर्थभेदायाः-नामाख्यातादि-वीणावेणुमृदङ्गशब्दादिरूपानेकभेदायाः । आह खल्वपि-चत्वारि वाक्परिमिता पदानि-इति ऋचमन्ये इति तद्व्याख्यातारः ॥

(भाष्यम्)

उतत्वः—

"उत त्वः पश्यन्न ददर्श वाच-
मुत त्वः शृण्वन्न शृणोत्येनाम् ।
उतो त्वस्मै तन्वं विसस्रे
जायेव पत्य उशती सुवासाः ॥"

अपि खल्वेकः पश्यन्नपि न पश्यति, अपि खल्वेकः शृण्वन्नपि न शृणोत्येनामिति-अविद्वांसमाहार्धम् ॥ उतो त्वस्मै तन्वं विसस्रे=तनुं विवृणुते । जायेव पत्य उशती सुवासाः । तद्यथा—जायेव पत्ये कामयमाना सुवासाः स्वमात्मानं विवृणुते, एवं वाक् वाग्विदे स्वात्मानं विवृणुते ॥ वाङ्नो विवृणुयादात्मानमित्यध्येयं व्याकरणम् ॥ उत त्वः ॥

(प्रदीपः) उत त्व इति । त्वशब्दोऽन्यवाची । उतशब्दः-अपिशब्दस्यार्थे । स च भिन्नक्रमः, प्रत्यक्षेण शब्दस्वरूपमुपलभमानोऽप्यर्थापरिज्ञानान्न पश्यतीत्यर्थः ॥ उतो इति । 'उत-उ' इति निपातसमाहारः ॥ अविद्वांसमाहार्धमिति । अविद्वल्लक्षणमर्थमर्द्धर्च आहेत्यर्थः ॥

(उद्योतः) उतत्व इति । 'उत'शब्दोऽप्यर्थे ॥ बहूनामपि समानपृष्ठोदरपाणिपादानामध्ययनमधीयानानामेकः कश्चित्पश्यन्नपि स्वभ्यस्ताध्ययनोऽपि तीक्ष्णबुद्धिरपि सन्न पश्यति, अर्थानभिज्ञत्वात् । अर्थपरिज्ञानफला हि वाक्-इत्यभिप्रायः । एवं-एकः शृण्वन्नपि न शृणोत्येनां वाचम्, य एव ह्यर्थं सम्यगवबुध्यते तेनैव सा सम्यक् श्रुता भवति ॥ एवमर्धेनाविद्वांसं निन्दित्वाऽर्धान्तरेण विद्वांसं स्तौति-उतो त्वस्मै । अप्येकस्मै=कस्मैचिद्वैयाकरणाय तन्वं=शरीरं विसस्रे=विवृणोति-प्र[का]शयति । सम्यक् ज्ञानं हि प्रकाशनमर्थस्य । अर्थो हि वाचः श[री]रम् ॥ अथोपमायुक्तयोत्तमया वाचाऽन्त्यपादेनार्थं प्रशंसति-यथा जाया विवृतसर्वाङ्गावयवा भूत्वोशती=कामयमाना भर्त्रे

इति ॥ विवरेषु-आधारादिषु प्रसृतिरभिव्यक्तिर्यस्येत्यर्थः ॥ बिन्दुतः प्राक्प्रक्रिया तु मञ्जूषादौ स्पष्टा ॥ विस्तरोऽपि तत एव ज्ञेयः ॥

[भाष्ये] देवताप्रसादजनकं चैतदित्याह—भाष्ये—उतत्व इति । अत्रोतशब्दोऽप्यर्थे खल्वर्थे वा । एवं च अन्यतरस्यार्थिको लाभः, अध्याहारो वा ॥ त्वशब्दोऽन्यार्थ एकत्वावच्छिन्नार्थो वा ॥ एकोऽवैयाकरणो निश्चयेन एनां वाचं स्वरूपेण पश्यन्नपि स्वभ्यस्यन्नपि न पश्यति न जानाति, अर्थापरिज्ञानात् ॥ एवमन्य एनां स्वरूपेण शृण्वन्नपि उक्तहेतोरेव न शृणोति फलाभावात् इति भाष्यार्थः ॥ इतिरर्थार्धसमाप्तौ ॥ अत एवात्र योग्यं कर्तारं सूचयन्नुपसंहरति—अविद्वांसमिति ॥

[भाष्ये] तदेवाह—भाष्ये—[८ मप०] उतो त्वस्मै इति । उतशब्दोऽप्यर्थे । उशब्दो निश्चये ॥ एकस्मै स्वतनूमपि निश्चयेन विसस्रे-प्रकाशयति । सृधातोः 'छन्दसि लुङ्लङ्लिटः' इति वर्तमाने लिट् । धातूनामनेकार्थत्वात्प्रकाशने वृत्तिः ॥ एवं ददर्शेत्यत्रापि बोध्यम् ॥ अत एव भगवता तथैव व्याख्यातम् ॥ 'अमि पूर्वः' इत्यत्र 'वा छन्दसि' इत्यनुवृत्त्या तन्वमित्यत्र यणादेशः । तदेतद् ध्वनयन्नाह—तनुं विवृणुत इति । अर्थरूपमित्यर्थः ॥ एतेन कृत्स्नां शब्दार्थरूपामिति कृष्णोक्तमपास्तम्, निरुक्तादिविरोधात् ॥ उक्तं दृष्टान्तं विशदयति—तद्यथेति ॥ पत्ये उशती कामयमाना । वशेः कान्त्यर्थात् शतरि संप्रसारणादौ रूपम् ॥ जाया-गर्भग्रहणधारणादियोग्या यतः सुवासाः-निर्णिक्तसूक्ष्मतमवस्त्रा तनूं सर्वावयवां विवृणुते इत्यर्थः ॥ अत एव भाष्ये तनुमित्यस्य व्याख्यानं स्वमात्मानमिति । स्वीयं सकलस्वरूपमिति तदर्थः । एवमग्रेऽपि वागेव शास्त्राभ्यासादिप्रसन्ना दुर्ज्ञानतया पूर्वोक्तार्थान्तिके कर्त्रीत्याह—एवमिति । वाग्विदे-वैयाकरणाय ॥ स्वात्मानम्, अर्थ उक्तः ॥ नन्वेतावता किमत आह—[११ शप०] वागिति ॥ नः-अस्मान् प्रति, अस्मभ्यमिति वा ॥

[प्रदीपे] तदर्थमाह कैयटे—अविद्वदिति ॥ विशेष्यभूतवाक्यार्थाश्रयत्वेन स तमाहेत्यर्थः ॥ 'अर्धर्चः' इत्यत्र 'अर्धर्चाः पुंसि च' इति पुंस्त्वम् ॥ अनेन—'उत्तरार्धं विद्वांसं वैयाकरणमाह' इत्यर्थादुक्तप्रायम् ॥

[उद्योते] तत्सर्वं हृदि निधायाह—उद्योते—उतशब्द इति ॥ त्वशब्दस्य द्वितीयार्थाशयेनाह—बहूनामपीति ॥ पश्यन्नपीत्यस्यार्थमाह—स्वभ्येति ॥ अर्थानभिज्ञत्वे दृष्टापत्तिं निराचष्टे—[४ पं०] अर्थेति ॥ हि-यतः ॥ एवं-तेषां मध्य इति शेषः ॥ एनामित्यस्य व्याख्या वाचमिति ॥ अत्र हेतुमुक्तरूपमेवाह—[५ मप०] य एवेति ॥ हि-यतः ॥ सम्यगिति । अनेन न शृणोतीत्यस्य सम्यगश्रवणम्-अर्थः सूचितः ॥ एवमुक्तप्रकारेण उतोशब्दोऽप्यर्थे इत्याशयेनाह—[७ मप०] अप्येकस्मा इति ॥ सम्यग् ज्ञानमेव प्रकाशनमित्याह—सम्यगिति ॥ हि यतः ॥ नन्वेवमपि कथं शरीरप्रकाशोऽत आह—[८ मप०] अर्थो हीति । यत इत्यर्थः ॥ [९ मप०] यमेति । जायासादृश्यरूपेत्यर्थः ॥ उत्तमयेति । मध्यमादिरूपयेत्यर्थः ॥ वाचामिति । तत्कर्तृकप्रसादेनेत्यर्थः ॥ तमेव-वैयाकरणमेव ॥ [१० मप०] अङ्गं-शरीरम् ॥ [१३ शप०]—नार्थमिति । तद्रूपमर्थमित्यर्थः ॥ तस्यार्थं शब्दद्वारा चेत्यर्थः ॥ एवंमग्रेऽपि ॥ घनेति । निबिडेत्यर्थः ॥ [१४ शप०] स इति । वैया-

प्रेम्णा दर्शयत्यात्मानम् । कस्मिन् काले ? यदा सुवासाः=निर्णिक्तवासा नीरजस्का ऋतुकालेषु, तदा प्रीतितमां स्त्री पुरुषं प्रार्थयते । यथा स पुरुषस्तां यथावत्पश्यति, शृणोति तद्वचनार्थं; नान्यदा घनपटप्रावृतशरीराम् । एवं-स एवैनां वाचं पदशः प्रकृतिप्रत्ययविभागेन विगृह्यार्थमस्याः पश्यति शृणोति चेति । अयमर्थो निरुक्ततद्भाष्ययोः (१ अ० १९ ख०) स्पष्टः । भाष्ये—वाग्विदे=वैयाकरणाय ॥

(भाष्यम्)

सक्तुमिव—

"सक्तुमिव तितउना पुनन्तो
यत्र धीरा मनसा वाचमक्रत ।
अत्रा सखायः सख्यानि जानते
भद्रैषां लक्ष्मीर्निहिताऽधिवाचि ॥"

सक्तुः—सचतेर्दुर्धावो भवति, कसतेर्वा विपरीताद्विकसितो भवति । तितउ-परिपवनं भवति, ततवद्वा, तुन्नवद्वा । धीराः=ध्यानवन्तः, मनसा=प्रज्ञानेन, वाचमक्रत=अकृषत ।

'अत्रा सखायः सख्यानि जानते' अत्र सखायः सन्तः सख्यानि जानते=सायुज्यानि जानते ।

क्व ?

य एष दुर्गो मार्गः, एकगम्यो वाग्विषयः ॥

के पुनस्ते ?

वैयाकरणाः ॥

कुत एतत् ?

'भद्रैषां लक्ष्मीर्निहिताऽधिवाचि ।'

एषां वाचि भद्रा लक्ष्मीर्निहिता भवति । लक्ष्मीर्लक्षणाद्भासनात्परिवृढा भवति ॥ सक्तुमिव ॥

(प्रदीपः) **सचतेरिति** । 'षच-सेचने' इत्यस्य । **दुर्धाव इति** । दुःशोधः । यथा-तितउना सक्तोस्तुषाद्यपनीयते तथा व्याकरणेन वाचोऽपशब्दा इत्यर्थः ॥ **कसतेरिति** । पृषोदरादित्वाद्वर्णव्यत्ययः ॥ **ततवदिति** । विस्तारयुक्तमित्यर्थः ॥ **तुन्नवदिति** । बहुच्छिद्रम् ॥ **धीरा इति** । वैयाकरणाः ॥ **वाचमक्रतेति** । अपशब्देभ्यो विविक्तां कृतवन्तः । 'मन्त्रे घस-' इति च्लेर्लुकि सति 'अक्रत' इति रूपम् ॥ **अत्रा सखाय इति** । 'ऋचि तुनुघ-' इति दीर्घः । **सखायः**=समानख्यातयो भेदग्रहस्य निवृत्तत्वात्सर्वमेकमिति मन्यन्ते ॥ **सख्यानीति** । सायुज्यानीत्यर्थः ॥ **एकगम्य इति** । ज्ञानेनैव प्राप्यः ॥ **वाचीति** । वेदाख्ये ब्रह्मणि या लक्ष्मीर्वेदान्तेषु परमार्थसंविल्लक्षणोक्ता सैषां निहितेत्यर्थः ॥

(उद्द्योतः) भाष्ये—**सक्तुमिवेति** । यत्र-व्याकरणे धीराः=ध्यानवन्तः सन्तस्तितउना सक्तुमिव ध्यानयुक्तमनसा तत्करणज्ञानेन वाचमक्रत=अकृषत-असाधुभ्यो विविक्तां कृतवन्तस्ते तत्करणेन शुद्धचित्ता अत्र=ब्रह्मप्रतिपादकशब्दे शब्दार्थयोरभेदमुख्या सखायः=समानख्यातयः-समानज्ञानाः, तच्छब्दे ब्रह्मैकत्वज्ञान-

---

करण एवेत्यर्थः ॥ अत्र संमतिमाह—[१५ शप०] **अयमिति** ॥

[भाष्ये] क्रमप्राप्तं साधकमन्यदप्याह—भाष्ये—**सक्तुमिवेति** ॥

[भाष्ये] तत्र सक्तुशब्दार्थमाह—भाष्ये प्रतीकं धृत्वा **सक्तुः सचतेरिति** ॥

[भाष्ये] विनिगमनाविरहादाह भाष्ये—**कसतेरिति** ॥ यद्वा यतः 'कस गतौ' इत्यस्माद्विकासार्थकात् पृषोदरादित्वाद्विपरीतात्प्राग्वत् कर्मणि तुनि रूपम्, अतो विकसितार्थप्रतिपादको भवतीत्यर्थः ॥ **तितेति** । 'तनोतेर्डउः सन्वच्च' इति डउः । विक्षेपोच्चारणसामर्थ्यात्संध्यभावः । अव्युत्पन्नं वा ॥

[भाष्ये] **परिपवनं**-परिशोधनम् । करणे ल्युट् ॥ परिशोधनकरणत्वस्यातिप्रसक्तत्वाच्चितउशब्दव्युत्पत्तिमाह—**ततेति** । एतेन तनोतेरेवेदं रूपमिति सूचितम् ॥

[भाष्ये] अस्याप्यतिप्रसक्तत्वादाह—भाष्ये—**तुन्नेति** । तुन्नानि छिद्राणि यस्य सन्तीति भूम्नि मतुप् ॥

[भाष्ये] [९ मप०]—**वाचमिति** । शुद्धामिति शेषः ॥ **अकृषत**-कृतवन्तः ॥

[भाष्ये] अत्रासखाय इत्यत्र नत्रादि नेति ध्वनयन्नाह—भाष्ये [१० मप०]—**अत्र सखाय इति** ॥ तदर्थमाह—**समानेति** । तस्यार्थः प्रागुक्तो बोध्यः ॥ एवमग्रेऽपि ॥ कैयटेन तथार्थकरणाद् भाष्ये '**समानख्यातयः सायुज्यानि जानते**' इति पाठो नास्तीति प्रतीयते । सांप्रतं तु भाष्ये तथोपलभ्यते ॥

[भाष्ये] पूर्वं विशिष्य कर्तुरनुल्लेखादाह—[मा० १४ शप०] **के पुनरिति** । सायुज्यप्राप्तिकर्तारः पुनः के इत्यर्थः ॥ उत्तरमाह—**वैयेति** ॥ **कुत इति** । तेषामेव तत्प्राप्तिकर्तृत्वमिति कुत इत्यर्थः ॥ उत्तरमाह—**भद्रैषामिति** । यत इत्यादिः ॥ तदर्थमाह [१८ शप०]—**एषामिति** । अधीत्यस्य निरर्थकत्वादनुपन्यासः । श्लेषपूरणं वा ॥

[भाष्ये] लक्ष्मीशब्दार्थमाह—भाष्ये [८ शप०] **लक्ष्मीरिति** । तथाच भासनार्थाद् 'लक्ष दर्शनाङ्कनयोः' इत्यस्मादौणादिको '**लक्षेर्मुट् च**' इतीकार इति भावः ॥

[प्रदीपे] तदाह कैयटे [२ यप०] **दुःशोध इति** ॥ अत्रापि प्राग्वत् खल् ॥ [३ यप०] **वाच इति** । पञ्चम्यन्तम् । अपनीयन्त इति शेषः ॥

[प्रदीपे] तदाह—कैयटे [४ मप०] **विस्तारेति** ॥

[प्रदीपे] तदाह—कैयटे [५ मप०] **बह्विति** । बहुव्रीहिः ।

[प्रदीपे] धाधातोरौणादिके क्रनि '**घुमास्था-**' इतीत्वे धीरा इति रूपम्, धातूनामनेकार्थत्वाद् ध्याने वृत्तिरिति कृष्णादयः । ध्यैधातोरेव तथा रूपमिति वयम् ॥ ध्यानं व्याकरणविषयकम् । अत एव विशिष्टार्थमाह—कैयटे [५ मप०] **वैयेति** ॥

[प्रदीपे] तदाह—कैयटे [६ डप०] **अपेति** ॥

[प्रदीपे] अत एवाह—कैयटे [८ मप०] **ऋचि त्विति** । **भेदेति च** ॥

वन्तस्तेनैव दृष्टान्तेन सर्वपदार्थेषु ब्रह्मनिरूपिताभेदज्ञानवन्तः सख्यानि=सायुज्यानि जानते, प्राप्नुवन्तीत्यर्थः । यत एषां वाचि भद्रा लक्ष्मीः स्वप्रकाशब्रह्मरूपा अधि=अधिकं निहिता=स्थिता भवतीति ऋगर्थः ॥ **सचतेर्दुर्धाव इति** । यतः सचतेः, अतो दुःशोधार्थप्रतिपादको भवतीत्यर्थः ॥ तितउशब्द इत एव भाष्यान्नपुंसकः । **'चालनी तितउः पुमान्'** इति कोशात्पुंलिङ्गोऽपि ॥ **विस्तारेति** । **'तनोतेर्डउः सन्वच्च'** इति व्युत्पत्तेरिति भावः ॥ **तुन्नेति** । तुद्धातोः **कर्मणि डउः सन्वच्चेति** भावः ॥ **ध्यानं**-ज्ञातार्थभानम् ॥ **'मनसा'** इति व्यापारपरं, तदाह—**प्रज्ञानेनेति** ॥ भाष्ये—**क्वेति** । 'किं तत् यत्र सायुज्यानि प्राप्नुवन्ति' इति **प्रश्नः** ॥ उत्तरयति—**य एष इति** । दुर्गमार्गप्राप्यत्वात् दुर्गमार्गत्वोपचारः ॥ दुर्गत्वमेवाह—**एकेति** ॥ **ज्ञानेनैवेति** । निर्विकल्पकज्ञानेनैवेत्यर्थः । अत एव दुर्गत्वं, **'नान्यः पन्थाः'** इति श्रुतेरिति भावः ॥ भाष्ये—**वाग्विषय इति** । अत एव श्रवणापपत्तिः ॥ **वाक्** वेदरूपाऽत्र ॥ **वेदान्तेष्विति** । **सत्यं ज्ञान**मित्यादिषु । **परमार्थसंविल्लक्षणा**-परमार्थब्रह्ममात्रविषयाऽखण्डार्थरूपा सैषां वाचि निहितेत्यर्थः । सर्वोऽपि वेदस्तेषां ब्रह्मपरः, **वेदैश्च सर्वैरहमेव वेद्य** इत्युक्तेरिति भावः ॥ **अयं भावः**—ये शास्त्रतः प्रकृतिप्रत्ययविभागेन साधून् ज्ञात्वा शास्त्रार्थध्यानवन्तो मानसज्ञानेन वाचमसाधुभ्यः पृथक् कृतवन्तस्ते तज्ज्ञानपूर्वकैः साधुशब्दप्रयोगैर्लब्धान्तःकरणशुद्धयः, **अत्र य एष** दुर्गो मार्गो ब्रह्मरूपस्तत्रात्मना सह **समानख्यातयः**-त्यक्तभेदभावनाः **सख्यानि**-सायुज्यानि प्राप्नुवते । यत **एषां वाचि**-वेदाख्ये ब्रह्मणि सर्वभासकब्रह्मरूपा सा **अधि**=अधिकं **निहिता** भवति । एतच्छास्त्रसाध्यप्रयोगव्यङ्ग्यस्य ध्वनिरूपवैखरीरूपरूपितस्यैव तैर्वाचकत्वस्वीकारेण तस्य चात्यन्तविचारे ब्रह्मातिरेके मानानुपलम्भेन तत्तदुपाधिभिन्नचित एव बोधकतया तैर्ग्रहात् । एवं सर्वबोधकेषु ब्रह्मबुद्धौ जातायां तेनैव दृष्टान्तेन सर्वपदार्थेषु **ब्रह्मबुद्धिर्वैयाकरणानामिति** ॥ यत्तु पदपदार्थवाक्यार्थमर्यादया **'सत्यं-'** इत्यादितस्तेषां तद्बोधात्सा तेषां वाचि निहितेति, तन्न; **'यतो वाचो निवर्तन्ते अप्राप्य मनसा सह'** इति श्रुत्या ब्रह्मणस्तन्मर्यादया शब्दाबोध्यत्वोक्तेः । तत्र हि 'अप्राप्य' इत्यस्य संबन्धज्ञानेऽविषयीभूय-असंबध्य चेत्यर्थः । आद्यं शब्दे, अन्त्यं मनसि ॥ शुद्धचित्तस्य तूभयमपि बोधकमखण्डविषयस्य, **दृश्यते त्वग्र्यया बुद्ध्येति** श्रुत्यन्तरात्; न तु पदपदार्थमर्यादयेति बोध्यम् । [एवञ्च सर्वबोधकेषु ब्रह्मबुद्धौ जातायांस्तेनैव दृष्टान्तेन सर्वपदार्थेष्वपि ब्रह्मबुद्धिर्वैयाकरणानामिति तात्पर्यम् ॥]

[प्रदीपे] **एकगम्य** इत्यस्यैकेनैव गम्य इत्यर्थः । तमाह—कैयटे [१० मप०] **ज्ञानेनैवेति** ॥

[प्रदीपे] कैयटे [११ शप०] **वेदाख्ये इति** । वाचीत्यस्यावृत्त्योभयत्रान्वय इति भावः ॥

[उद्द्योते] सक्तुमिति स्पष्टार्थं, तदर्थमाह—[उ० १ मप०] **ये यत्रेत्यादि** । विषयत्वं सप्तम्यर्थः । [२ यप०] **सक्तुमिवेति** । सक्तुं पुनन्त इवेत्यर्थः ॥ शुद्धमनसो हेतुत्वादाह—**ध्यानेति** ॥ तदपि सव्यापारमित्याह—**तत्करणेति** ॥ **वाचमक्रतेति** । **'मन्त्रे घस-'** इति लेर्लुङ् । शुद्धामित्यर्थः ॥ तदाह—[३ यप०] **असाध्विति** ॥ **विविक्तामिति** । विवृक्तामिति क्वचित्पाठः ॥ **अत्रा**-सखाय इत्यत्र **'ऋचि तुनुघ-'** इति दीर्घ इति ध्वनयन्नाह—[४ थप०] **अत्रेति** ॥ एतेन तत्र व्याकरणविषय इति रक्षोक्तमपास्तम् । तद्ध्वनयन्नाह—**ब्रह्मेति** । व्याकरणप्रतिपाद्ये इत्यर्थः ॥ **सखाय** इत्यस्य व्याख्या **समानेति** ॥ तस्य व्याख्या **समानेति** ॥ तस्यार्थमाह—[५ मप०] **तच्छब्दे इति** । ब्रह्मप्रतिपादकशब्दे इत्यर्थः ॥ तुल्ययुक्त्या आह—**तेनैवेति** ॥ [७ मप०] **प्राप्नुवन्ति** ॥ **'यतः'** इति पाठः ॥ अत्र हेतुमाह—**यत इति** ॥ **एषां**-अत्र धीराणाम् ॥ [९ मप०] **भवतीति** । अत इति शेषः ॥

[उद्द्योते] असंबद्धत्वात्तदर्थमाह—[उ० ९ मप०] **यत इति** ॥ षच समवाये षच सेचने-इत्यन्यतरस्माद् दुःशोधार्थादौणादिके कर्मणि तुनि कर्त्रे च रूपमिति भावः ॥ अत एवाह—**अत इति** ॥ भाष्ये **दुर्धाव** इत्यत्रेषद्दुःस्विति दुःपूर्वाद्धात्रेः कर्मणि खलित्याशयेनाह—**दुःशोध्यार्थेति** ॥

[उद्योते]—[११ शप०] **नपुंसकः**-नपुंसकलिङ्गः ॥ कोशासंगतिं परिहरति—**चालनीति** । अत एव **'स्याद्वास्तु हिङ्गु तितउ'** इति त्रिकाण्डशेषः संगच्छते ॥

[उद्योते] तदाह—[उ० १२ शप०] **तनोतेरिति** । इदं सर्वं शाकटायनादिरीत्या बोध्यम् ॥

[उद्योते] तदाशयमाह—[उ० १३ शप०] **तुदेति** । व्यथनार्थकादिति भावः ॥ एवं च नातिप्रसक्तिरिति बोध्यम् ॥

[उद्योते] तत्र ध्यानपदार्थमाह—[उ० १४ शप०] **ज्ञातार्थभावनमिति** । सततपरिशीलनमित्यर्थः । धारणेति यावत् ॥

[उद्योते] प्रश्नोत्तरयोः सामानाधिकरण्याय प्रातिपदिकार्थप्रश्ने तात्पर्यमित्याशयेनाह—[उ० १५ शप०] **किं तदिति** ॥ [१६ शप०] **दुर्गमार्गेति** । तस्य दुष्प्रापत्वादिति भावः ॥ [१७ शप०] **दुर्गत्वमिति** । अतिविषमत्वमित्यर्थः । मार्गे इति भावः ॥

[उद्योते] सविकल्पकनिवृत्तये आह—[उ० १७ शप०] **निर्विकेति** । **अत एव**-तस्यान्यथा दुःसाध्यत्वादेव ॥ एवव्यवच्छेद्यमाह [१८ शप०] **नान्य इति** ॥ अवागितिच्छेदनिरासायाह— [१९ शप०], **भाष्ये वाग्विषय इति च्छेद इति** ॥ **अत एव**-विषयत्वादेव ॥ एवं च साधनसंपत्तिसत्ता सूचिता ॥ ननु कीदृशवाग्विषयत्वं तस्य, तत्राह—[१९ शप०] **वाग्वेदरूपाऽत्रेति** ॥

[उद्योते २१ शप०] **परमार्थेत्यादि रूपान्तं** समस्तमेकं पदम् ॥ नन्वेवं कथं सर्ववेदनिष्ठा सा लक्ष्मीरित्यत आह [२१ शप०] **सर्वोऽपीति** ॥ **ब्रह्मपर इति** । तत्तात्पर्यक इत्यर्थः ॥ अन्येषामज्ञान-

लक्षणादित्यस्य व्याख्या—भासनादिति ॥ परिवृढा—अज्ञाननिवर्तने प्रभ्वी ॥ एते च मन्त्राः सर्वानुक्रमेऽन्यत्र विनियुक्ता अपि भाष्यप्रामाण्यादेतत्तात्पर्यका अपीति बोध्यम् ॥ 'चत्वारि-' इत्यादि ऋक्चतुष्टयं व्याकरणस्य मोक्षजनकत्वं प्रतिपादयति ॥

(भाष्यम्)

सारस्वतीम्—

याज्ञिकाः पठन्ति—"आहिताग्निरपशब्दं प्रयुज्य प्रायश्चित्तीयां सारस्वतीमिष्टिं निर्वपेत्" इति ॥ प्रायश्चित्तीया मा भूमेत्यध्येयं व्याकरणम् ॥

सारस्वतीम् ॥

(प्रदीपः) **प्रायश्चित्तीयामिति** । भवार्थे 'वृद्धाच्छः' ॥ **प्रायश्चित्तीया इति** । प्रायश्चित्ताय=पापशोधनाय श्रुतिस्मृतिविहिताय कर्मणे हिताः=तन्निमित्तोत्पादका मा भूमेत्यर्थः ॥

(उद्द्योतः) भवार्थे इति । प्रायश्चित्तसाधनत्वेन तद्भवत्वम् ॥

(भाष्यम्)

दशम्यां पुत्रस्य—

याज्ञिकाः पठन्ति—"दशम्युत्तरकालं पुत्रस्य जातस्य नाम विदध्यात् घोषवदाद्यन्तरन्तस्थमवृद्धं त्रिपुरुषानूकमनरिप्रतिष्ठितम् । तद्धि प्रतिष्ठिततमं भवति । द्व्यक्षरं चतुरक्षरं वा नाम कृतं कुर्यान्न तद्धितम्" इति ॥

न चान्तरेण व्याकरणं कृतस्तद्धिता वा शक्या विज्ञातुम् ॥

दशम्यां पुत्रस्य ॥

(प्रदीपः) **दशम्युत्तरकालमिति** । दशम्या उत्तर इति 'पञ्चमी-' इति योगविभागात्समासः । ततः कालशब्देन बहुव्रीहिः । क्रियाविशेषणं चैतत् । दश दिनान्यशौचं भवति—इति दशम्युत्तरकालमित्युक्तम् । येऽपि गृह्यकाराः पठन्ति—'**दशम्यां पुत्रस्य**' इति, तैर्दशम्यामिति सामीपिकमधिकरणं व्याख्येयम् ॥ **घोषवदादीति** । घोषवन्तो ये वर्णाः शिक्षायां प्रदर्शिताः, तदादि ॥ **अन्तरन्तस्थमिति** । मध्ये यरलवा यस्य तदित्यर्थः ॥ **त्रिपुरुषानूकमिति** । नामकरणे योऽधिकारी पिता तस्य ये त्रयः पुरुषास्ताननुकायति=अभिधत्त इति त्रिपुरुषानूकम्, '**अन्येषामपि दृश्यते**' इति दीर्घः ॥

(उद्द्योतः) पञ्चमीति योगविभागादिति । 'सुप्सुपा' इति तु युक्तम् ॥ ननु 'दशम्यां पुत्रस्य' इति प्रयोजनस्वरूपगणने भाष्ये उक्तम् । गृह्येऽपि तथैव पठ्यते, अतः 'दशम्युत्तरकालं' इत्ययुक्तमत

निरासायाह—[२३ शप०] अयं भाव इति ॥ शास्त्रतः—व्याकरणतः ॥

[उद्द्योते ११ शप०] तैः—वैयाकरणैः । एवमग्रेऽपि [११ शप०] ॥ परमतात्पर्यमाह—[३१ शप०] एवमिति ॥ प्राचामुक्तिं खण्डयति [३३ शप०] यत्त्विति ॥ अप्राप्येत्यस्योभयत्र संबन्धायाह—[३६ शप०] तत्रेति ॥ [३७ शप०] उभयमिति । वाङ्मनसरूपमित्यर्थः ॥ स्पष्टार्थमुपसंहरति [३८ शप०]—न त्विति ॥

[उद्द्योते] परिगृहीतेति श्लोकार्थनिरासायाह—[उ० ४१ शप०]—अज्ञानेति ॥ विरोधं परिहरति—एते चेति ॥ सर्वानुक्रमे छन्दऋषिदेवतानामेव प्रतिज्ञापुरःसरमनुक्रान्तत्वादाह—भाष्ये इति ॥ [४२ शप०] अन्यत्र—अग्निध्यानादौ ॥ परमतात्पर्यार्थमाह—[४३ शप०] चत्वारीति । चत्वारि शृङ्गा इत्यादीत्यर्थः ॥

[भाष्ये] अग्निमाधानेन दानपरिग्रहादिवद्व्याकरणमवश्यमध्येयमित्याह—भाष्ये-सारस्वतीमिति ॥ याज्ञिकाः पठन्तीति प्राग्वत् ॥ यद्यपि अनारभ्याधीतेन 'नानृतं वदेत्' इति निषेधेनार्थानृतवच्छब्दानृतस्यापि सत्त्वेन सर्वत्रापशब्दप्रयोगे पुरुषदोषा बहवः, तथापि दर्शपूर्णमासप्रकरणपठितेन तादृशेन वाक्येन क्रतोरपि वैगुण्यमित्याशयेनाह—आहिताग्निरिति ॥ क्रतुमध्य इति शेषः ॥ वस्तुतस्तु अन्यत्र दोषाभावसूचकमेवात्राहिताग्निपदमित्यन्यत्र स्फुटम् ॥ एवं च नारायणोक्तं युक्तमेवेति बोध्यम् ।

[भाष्ये] भाष्ये सारस्वतीं सरस्वतीदेवताकाम् ॥

[प्रदीपे] कैयटे—हिता इति । 'तस्मै हितम्' इत्यर्थे वृद्धाच्छः ॥ अत्र प्रायश्चित्तपदमुक्तकर्मपरमेवेति भावः ॥ प्राग्वत् यज्ञकर्मण्यपशब्दप्रयोक्तारो मा भूमेत्यध्येयं व्याकरणमिति फलितोऽर्थः ॥

[उद्द्योते] ननु श्रुतिस्मृतिविहितं पापशोधककर्म प्रायश्चित्तमिति कथमिष्टेस्तद्भवत्वमत आह—उद्द्योते—प्रायश्चित्तेति ॥ तथा चात्र प्रायश्चित्तपदमन्तःकरणशुद्धिपरमिति भावः ॥

[भाष्ये] नामकरणे उपयोगमाह—भाष्ये दशम्यामिति ॥ याज्ञिकाः पठन्तीति पूर्ववत् ॥ 'वटे गावः सुशेरते' 'मासिकं' इत्यादिवत् 'दशम्याम्' इत्यौपश्लेषिकेऽधिकरणे सप्तमीत्याशयेनाह—दशम्युत्तरेति ॥

[भाष्ये] अवृद्धं-वृद्धसंज्ञाक्षररहितम् ॥

[भाष्ये] अत एव स्तौति—तद्धीति ॥ कृतमिति । तदन्तमेवेत्यर्थः ॥ एवमग्रेऽपि ॥

नियमापूर्वफलितदनिष्टाभावात् तद्धितान्तस्यापि प्राप्तिरिति तन्निषेधति—न तद्धितमिति ॥ तत्करणेन न केवलं नियमापूर्वहानिः, अपि तु दुरितमपीत्यर्थः ॥

नन्वेतावता किमत आह—भाष्ये—नचान्तेति ॥ नहीत्यर्थः ॥ विज्ञातुमिति । 'अतोऽध्येयं व्याकरणम्' इति शेषः ।

[प्रदीपे] कैयटे [५ शप०] सामीपिकमिति ॥ उप समीपे श्लेषः संबन्धस्तत्कृतमित्यर्थः ॥ [६ शप०] घोषवन्त इति । घोषशब्दो धर्मपरः ।

[प्रदीपे] कैयटे [९ शप०] त्रयः पुरुषा इति । पितृपिता-

आह—तैरपीति ॥ शिक्षायामिति । ते च-हशः । अन्तरन्तःस्था यस्येत्यर्थः ॥ त्रिपुरुषानूकम् । त्रिपुरुषशब्दो द्विगुः । मूलविभुजादित्वात्कः ॥ भाष्ये—अनरीति । अमनुष्ये-अरिभिन्ने-इति वाऽर्थः ॥

(भाष्यम्)

सुदेवो असि वरुण—

"सुदेवो असि वरुण यस्य ते सप्त सिन्धवः ।
अनु क्षरन्ति काकुदं सूर्म्यं सुषिरामिव ॥"

'सुदेवो असि वरुण'-सत्यदेवोऽसि, 'यस्य ते सप्त सिन्धवः ।'-सप्त विभक्तयः, 'अनुक्षरन्ति काकुदम्' काकुदं-तालु । काकुः=जिह्वा, साऽस्मिन्नुद्यत इति-काकुदम् । 'सूर्म्यं सुषिरामिव ।' तद्यथा—शोभनां-मूर्मिं सुषिरामग्निरन्तः प्रविश्य दहति, एवं ते सप्त सिन्धवः=सप्त विभक्तयस्ताल्वनुक्षरन्ति । तेनासि सत्यदेवः ॥ सत्यदेवाः स्यामेत्यध्येयं व्याकरणम् ॥

सुदेवो असि ॥

(प्रदीपः) सुदेवो असीति । वरुणस्येयं स्तुतिः । यतो हेतोर्व्याकरणज्ञानाद्वरुणः सत्यदेवः, ततो हेतोरन्येऽपि सत्यदेवा भवन्तीत्यर्थः ॥ सिन्धव इति । नद्य इव विभक्तय इत्यर्थः ॥ अनुक्षरन्तीति । ताल्वनुप्राप्य प्रकाशन्त इत्यर्थः ॥ साऽस्मिन्नुद्यत इति । अनेकार्थत्वाद्धातूनां 'उत्क्षिप्यते' इत्यर्थः ॥ सूर्म्यमिति । 'सूर्मिं' इति प्राप्ते 'अमि पूर्वः' इत्यत्र 'वा छन्दसि' इत्यनुवृत्त्या यणादेशः ॥

(उद्योतः) सत्यदेवा इति । वरुणे यथा-सत्येन दीव्यति द्योतत इति यौगिकोऽयं शब्दस्तथाऽन्येष्वपीत्यर्थः ॥ यस्येति । पञ्चमीस्थाने षष्ठी । यस्मात्ते काकुदं=तालु प्राप्य सिन्धवः सप्तसमुद्ररूपाः सप्तविभक्तयोऽनुक्षरन्ति, प्रकाशन्ते-इत्यर्थः ॥ अनेकार्थत्वादिति । वदेरधिकरणे 'घञर्थे-' इति कः । शकन्धुवत्पररूपं, पृषोदरादित्वाद्वैकस्योकारस्य लोपः । नुदेर्वाऽधिकरणे कः, पृषोदरादित्वान्नुलोपः ॥

महप्रपितामहा इत्यर्थः ॥ तानिति । तेषामन्यतममित्यर्थः ॥ इदं च फलितार्थकथनम् ॥

[उद्योते] योगविभागस्य भाष्यारूढत्वादाह—उद्योते—सुप्सुपेतीति ॥ इदमेव प्रतिपादयन्नाह—[२ यप०] नन्विति ॥

[उद्योते] कैयटेन वृत्त्यर्थस्योक्तत्वाद्विग्रहमाह—[उ० ४ थप०] अन्तरिति ॥ अन्तःस्थाशब्द आकारान्तः ॥

[उद्योते] शब्दार्थमाह—[उ० ५ मप०] त्रिपुरुषशब्दो द्विगुरिति ॥ समाहारद्विगुरित्यर्थः ॥ पात्रादित्वात् स्त्रीत्वाभाव इति भावः ॥ अमनुष्य इति । देवतादौ पर्यवसितमित्यर्थः ॥ यद्वा—अरौ प्रतिष्ठितं न भवतीत्यर्थः ॥ तत्फलितमाह—अरिभिन्ने इति ॥ तद्भिन्ने मित्रादावित्यर्थः ॥

[भाष्ये] तथाऽन्यमपि क्रमप्राप्तमृङ्मन्त्रमाह—भाष्ये—सुदेवो असीति । 'प्रकृत्यान्तः-' इति प्रकृतिभावः ॥

[भाष्ये] भाष्ये—सुदेव इति । हे वरुण त्वं सुदेवो असि ॥ अस्य व्याख्या—सत्यदेवोऽसीति ॥

[भाष्ये] तदेवाह—भाष्ये—यस्य ते सप्तेत्यादि ॥

[भाष्ये] भाष्ये—ताल्विति । तस्य तत्र यौगिकत्वम् ॥ रूढिव्यावृत्तये आह—काकुरिति ॥ साऽस्मिन्नुद्यत इति फलितार्थकथनम् ॥

[भाष्ये] अत्र दृष्टान्तमाह—भाष्ये—सूर्म्यमिति ॥ तदुपपादयति—शोभनामूर्मिमिति । अनेनोर्मिरयःप्रतिमा न तु सूर्मिः इति सूचितम् ॥

[भाष्ये] उपसंहर्तुं दार्ष्टान्तिके पुनर्योजयति भाष्ये—एवं त इति ॥ एवमित्येव पाठे 'ते' इति शेषः ॥

[भाष्ये] निगमयति भाष्ये—तेनासीति ॥ ननु किमेतावताऽत आह—सत्येति । व्याकरणाध्ययनस्य सत्यदेवत्वं फलमित्यर्थः ॥

[प्रदीपे] कैयटे—वरुणेति । बार्हस्पत्ये प्रगाथे इत्यादिः ॥

[प्रदीपे] सर्वमन्त्रतात्पर्यार्थमाह—कैयटे—यत इति । व्याकरणज्ञानाद्यतो हेतोः साध्वसाधुशब्दज्ञानपूर्वकं सुशब्दप्रयोगादित्यर्थः ॥

[प्रदीपे] कैयटे—नद्य इवेति । समुद्रा इत्यर्थः । लक्षणैवेति भावः ॥ विभक्तयः । उक्तोऽर्थः ॥ अनुक्षरन्तीत्यस्यार्थमाह—ताल्विति ॥ अध्याहारेणाह—अनुप्राप्येति ॥ क्वचित् 'प्राप्य'इत्येव पाठः ॥

[उद्योते] तत्तात्पर्यमाह—उद्योते—वरुणे इति ॥ सत्येनेति । साधुशब्दप्रयोगाख्येनेत्यर्थः ॥ 'देवितासि व्यवहरसि' इति कृष्णोक्तार्थनिरासायाह—दीव्यति द्योतत इति । अयं भावः—द्विविधमनृतम्—अर्थानृतं शब्दानृतं च । तत्र यथा भ्रान्तविप्रलम्भकै रजतत्वेनोपदिष्टस्य रङ्गस्य रजतस्थाने दानमनर्थहेतुः, तद्वत् साधुशब्दस्थानेऽसाधुशब्दप्रयोगः । तदभावाद्वरुणः सत्यदेव इति यौगिकः, न त्वश्वकर्णादिवद्रूढ इति भावः ॥

[उद्योते] तदर्थमाह उद्योते—यस्येतीति । व्यत्ययेनेति भावः ॥ प्राप्येत्यध्याहारलभ्यः, अन्यथाऽनुपपत्तेः ॥ सप्तवीति । सप्तत्वसंख्यासामान्यात्प्रथमादिसप्तत्रिकाणीत्यर्थः ॥ तथा च श्रुतौ लुप्तोपमा सूचिता ॥ व्याख्यानेऽपि तथा । अनेन क्रियाऽप्याक्षिप्ता भवतीति न न्यूनता ॥ प्रकाशन्त इति । मूर्तिमत्य इत्यादिः, अत इत्यन्तश्च ॥

[उद्योते] तद्ध्वनयन्—'अनेकार्थत्वात्' इति कैयटोक्तिवशादाह—[उ० ५ मप०] वदेरिति । उत्क्षेपार्थादिति भावः ॥ घञर्थे इतीति । वार्तिकेनेति भावः ॥ शकन्ध्विति । संप्रसारणे पूर्वरूपे काकोरुदमिति षष्ठीतत्पुरुषे इत्यादिः ॥ विनिगमनाविरहादाह—पृषोदेति ॥ 'सास्मिन्नुद्यते' इति भाष्यस्य संदिग्धत्वेनान्यथापि व्याख्यातुं शक्यत्वेन संप्रसारणाद्यभावादेकार्थत्वकल्पनालाघवादाह—नुदेर्वेति ॥

[उद्योते] तदाह—[उ० ७ मप०] सूर्मिमिति ॥ कोशादिप्रामाण्याद्दीर्घान्तोऽप्ययमित्यन्यदेतत् ॥ सामर्थ्यलभ्यमर्थं भाष्योक्तमाह—[८ मप०] प्रविश्येत्यादि ॥

[उद्योते] तत्तात्पर्यार्थमाह—[उ० ९ मप०]—एवं ताल्विति ॥ वरुणस्येति शेषः ॥

[उद्योते] तात्पर्यार्थमाह—उद्योते—अनेनेति ॥ वरुणतुल्यत्वप्रतिपादनेनेत्यर्थः ॥ स यथा स्वर्गवासी एवमन्योऽपि तादृश इति भावः ॥

[भाष्ये]—भाष्ये किं पुनरिति । पुनःशब्दो हेत्वर्थे वाक्या-

सूर्मि=शोभनामयःप्रतिमाम्, सुषिरां-'ऊषसुषि- इति रप्रत्ययेन' सच्छिद्रां प्रविश्याग्निर्यथा तत्रत्यं मलं भस्मीकृत्य प्रतिमां शुद्धां करोति, एवं तालुदेशे प्रकाशं प्राप्य विभक्तयः=विभक्त्यन्ताः शब्दाः शारीरं पापमपाकुर्वन्तीत्यर्थः ॥ अनेन स्वर्गप्राप्तिः फलमित्युक्तम् ॥

(उक्तप्रयोजनग्रन्थोपपत्तिप्रकरणम्)

(आक्षेपभाष्यम्)

किं पुनरिदं व्याकरणमेवाधिजिगांसमानेभ्यः प्रयोजनमन्वाख्यायते, न पुनरन्यदपि किंचित्-'ॐ' इत्युक्त्वा वृत्तान्तशः 'शम्' इत्येवमादीन् शब्दान्पठन्ति ?

(प्रदीपः) **किं पुनरिति।** ननु **'कानि पुनरस्य'** इति येन पृष्टं स एव कथं पृच्छति—**'किं पुनर्'** इति । एवं तर्हि भाष्यकारः प्रयोजनान्वाख्यानस्य विषयविभागं दर्शयति । पुरा वेदाध्ययनात्पूर्वं व्याकरणमधीयते ते बाल्यात्प्रष्टुमसमर्था इति न प्रयोजनमन्वाख्येयम् । अद्यत्वे तु स्वल्पायुष्ट्वात्पूर्वमेव वेदं प्रधानमधीयते, अतः प्रष्टुं समर्थत्वाद्व्याकरणाध्ययनस्य प्रयोजनं पृच्छन्तीत्यवश्यान्वाख्येयं प्रयोजनम् ॥ **न पुनरन्यदिति ।** वेदमप्यधिजिगांसमानेभ्य इत्यर्थः ॥ **ॐ इत्युक्त्वेति ।** अभ्युपगम्येत्यर्थः ॥ **वृत्तान्तश इति** । वृत्तान्तः प्रपाठक उच्यते । वृत्तान्तं वृत्तान्तं प्रति-इत्यर्थः ॥

(उद्द्योतः) **एवं तर्हीति** । 'वेदातिरिक्तविषय एव प्रयोजनान्वाख्यानं, न तु वेदविषये' इत्येवंरूपं-**विषयविभागम्** ॥ तृतीयस्य प्रश्न इत्यन्ये ॥ किंचित्पदार्थमाह—**वेदमपीति** । शेषपूरणमन्यत् । किं तत् किञ्चिदित्याकाङ्क्षायां—भाष्ये—**ओमित्युक्त्वेति** ॥ **'पठन्ति'** इत्यस्यानन्तरं **'तेभ्योऽपि'** इति शेषः ॥ एवञ्च वेदमधिजिगांसमानेभ्यो वेदाध्ययनप्रयोजनं किमिति नान्वाख्यायत इति प्रश्नः ॥ वेदाध्ययनवत् व्याकरणाध्ययनमपि प्रयोजनमन्तरैव कारि-

---

लंकारे वा ॥ एवमग्रेऽपि ॥ **इदं प्रयोजनमित्यन्वयः** ॥

[प्रदीपे] प्रयोजनान्वाख्यातारं प्रत्ययं प्रश्नः । अत एव तस्यायं प्रश्नो न, तत्प्रष्टुरपि नेत्याह—कैयटे—**ननु कानीति** ॥ तदावश्यकत्वज्ञानादानर्थक्यशङ्कायास्तस्यासंभवादिति भावः ॥ प्रश्नाकारमाह—**किमिति** ॥ पूर्वतनं तु प्रतीकम् ॥ यत्तु—फलान्युक्त्वा तदन्वाख्यानस्यावश्यकतां वक्तुं तस्यैवायमाक्षेपः—इति केचित् । तन्न, अग्रे तथाऽनुक्तेः । अत एव तद्विरोधापत्तेश्च ॥ तदेतद् ध्वनयन्नाह—कैयटे—**एवं तर्हीति** ॥ **भाष्यकार एव** ॥

[प्रदीपे] कैयटे—**दर्शयतीति** । स्वयमेव प्रश्नपूर्वकं दर्शयतीत्यर्थः ॥

[प्रदीपे] उत्तरग्रन्थे भाष्यकृतोक्तं विषयविभागमग्रैवाह—कैयटे—**पुरेति** ॥ युगान्तर इत्यर्थः ॥ **व्याकरणमिति** । तदाद्यङ्गानीत्यर्थः ॥ तदध्ययने हेतुगर्भं विशेषणमाह—[६ छप०] **प्रधानमिति** ॥

[प्रदीपे] वीप्सायां शसित्याशयेनाह—कैयटे—**वृत्तान्तमिति** ॥ **प्रतीत्येति** ।` अभिकृत्येत्यर्थः । वीप्साद्योतको वा प्रतिः ॥ **'पठन्तीत्यर्थः'** इति पाठस्तु सुगम एव ॥ **'वृत्तान्ततः'** इति पाठे तु तृतीयान्ताद् द्वितीयान्ताद्वाऽऽद्यादित्वात्तसिः ॥ वीप्सान्तर्भावो बोध्यः ॥

[उद्द्योते] **विषयविभागमित्यस्य** 'भिन्नं भिन्नं विषयम्' इत्यर्थनिरासायाह—उद्द्योते—**वेदातीति** ॥

[उद्द्योते] उक्तरीत्या प्रष्टृवक्त्रोः प्रश्नासंभवेऽपि प्रकारान्तरेण भाष्यस्य समञ्जसत्वादगतिकगतिरूपकैयटोक्तिरयुक्तेत्याशयेनाह—उद्द्योते—**तृतीयस्येति** ॥ उक्तद्वयभिन्नस्येत्यर्थः ॥

[उद्द्योते] कैयटात् **सर्वस्तदर्थ** इति प्रतीयते, तन्निरासायाह—उद्द्योते—**किंचिदित्यादि** ॥ **शेषेति** । अनुपक्षेपेणेति भावः ॥ कैयटोक्तकिंचित्पदार्थस्य भाष्यारूढत्वायाह—[उ० ३ यप०] **किं तदिति** ॥ [४ थप०] **माहेति** । विशिष्याहेत्यर्थः ॥ अत एवानन्वयवारणायाह—**पठन्तीत्येति** ॥ **शेष इति** । अध्याहार इत्यर्थः ॥ प्रयोजनमन्वाख्यायत इत्यस्यानुषङ्गः ॥ **शमित्यस्यादावुक्तिस्तु** प्राग्वज्ज्ञेया ॥ एतावद्ग्रन्थस्य तात्पर्यमाह— [५ मप०] **एवं चेति** ॥ अत्र तदन्वाख्याने चेत्यर्थः ॥

प्रश्नस्यापि परमतात्पर्यमाह—[७ मप०] **वेदेति** । एवं चेत्यादिः ॥ तदनन्वाख्याने चेति तदर्थः ॥ अधीष्वेत्याचार्यवचनादेवेति भावः ॥ [७ मप०] **प्रयोजनं**—तज्ज्ञानम् ॥ क्वचित्तथैव पाठः ॥ न चादौ विप्रलम्भशङ्ककान् प्रति तदुक्तिरिति वाच्यम्, तर्हि शतशस्तदुक्तावपि तच्छङ्कया प्रवृत्त्यनुपपत्तेः ॥ नचार्थात्प्रवृत्तान् प्रति प्रोत्साहनार्था तदुक्तिः, तर्ह्यन्यत्रापि तदर्थं तदुक्तेरावश्यकत्वात् ॥ अथ तत्र तद्विनैव निर्वाहः, तर्ह्यत्रापि तथेति भावः ॥ यत्तु वेदाध्ययनप्रकारं तृतीय एवाह—भाष्ये—**ओमिति** ॥ आचार्येण 'अधीष्व' इत्युक्ते "ओमभ्यादाने" इति विहितो दात्तप्लुतविशिष्टप्रणवमादावुच्चार्येत्यर्थः इत्याहू रत्नकरादयः । तन्न, एवं सति 'ओ३म्' इत्येव वाच्ये इत्युक्त्वेत्यस्य वैयर्थ्यस्य दुष्परिहरत्वात् । तत्र तथा प्रकारसत्त्वेऽपि प्रकृते तत्कथनानुपयोगाच्च । तदेतद् ध्वनयन्नाह—[उ० ८ मप०] **नन्वोमित्यधिकमिति** ॥ ओमित्युक्त्वेत्यधिकमित्यर्थः ॥ क्वचित्तथैव पाठः ॥ **अभ्युपगम्येतीति** । विशिष्टस्यायमर्थ इति भावः ॥ अत एव कैयटेन तथैवोक्तम् ॥ **विनैवेति** । अधीष्वेत्युक्ते तदारम्भमित्यादिः ॥

[भाष्ये] एतत्पदार्थमाह—भाष्ये—**संस्कारोपचरेत्यादि विदयमन्त इत्यन्तेन** ॥ क्रियाविशेषणमेतत् ॥

[भाष्ये]—भाष्ये—**ब्राह्मणा इति** । प्राग्वत् ॥ **व्याकरणमि**त्यङ्गानामुपलक्षणम् । प्राधान्यात्तस्योल्लेखः ॥ ततः किमित्याशङ्कायामत एवाह—[२ यप०] **तेभ्य इत्यादि** । अध्याध्येतृभ्य इत्यर्थः । **स्थानं**—प्रसिद्धं कण्ठादि ॥

[भाष्ये] नन्वेवं विशिष्टवेदपाठसिद्धिरेवेत्येतावता किमत आह—भाष्ये—**वेदमिति** ॥

[भाष्ये] प्रवक्तार इत्यत्र कर्माह—भाष्ये—**वेदाश्च इत्यादिमितीत्यन्तेन** ॥ **नः**—अस्माकम् । कर्तरि शेषत्वविवक्षया षष्ठी ॥ **सिद्धा लोकाच्च**—तद्व्यवहाराच्च ॥ अध्यापकशिक्षयैव स्थानादिज्ञानसिद्धेरक्षरग्रहणवदिति एतदनर्थकमित्याह—**अनर्थकमिति** ॥ **विप्रतीति ।** विरुद्धमर्थं प्रतिपन्ना-विप्रतिपन्ना, सा बुद्धिर्येषां तेभ्य इत्यर्थः ॥

[भाष्ये] तदेवाह—भाष्ये—**प्रमाणीति** ॥ यद्यपि मन्वादि-

ष्यन्तीति प्रयोजनविचारो व्यर्थ इति तात्पर्यम् ॥ नन्वोमित्यधिकमत आह—अभ्युपगम्येति । विनैव प्रयोजनज्ञानमिति शेषः ॥

(समाधानभाष्यम्)

पुराकल्प एतदासीत्—संस्कारोत्तरकालं ब्राह्मणा व्याकरणं स्माधीयते, तेभ्यस्तत्तत्स्थानकरणनादानुप्रदानज्ञेभ्यो वैदिकाः शब्दा उपदिश्यन्ते । अद्यत्वे न तथा । वेदमधीत्य त्वरिता वक्तारो भवन्ति ।

'वेदान्नो वैदिकाः शब्दाः सिद्धाः,

लोकाच्च लौकिकाः,

'अनर्थकं व्याकरणम्' इति । तेभ्य एवं विप्रतिपन्नबुद्धिभ्योऽध्येतृभ्य आचार्य इदं शास्त्रमन्वाचष्टे-इमानि प्रयोजनान्यध्येयं व्याकरणम्-इति ॥

(प्रदीपः) अद्यत्वेशब्दो निपातः—अस्मिन् काल इत्येतस्मिन्नर्थे वर्तते ॥ **त्वरिता इति** । विवाहादौ ॥

(उद्द्योतः) भाष्ये—उत्तरमाह—**पुराकल्पे इति** । युगान्तरे इत्यर्थः ॥ **संस्कारः**—उपनयनम् ॥ **करणं**—आभ्यन्तरप्रयत्नः ॥ **अनुप्रदानं**—नादादिबाह्यप्रयत्नः । तेनाधीतव्याकरणशिक्षेभ्य इत्यर्थः । ते तदानीमपि कर्मानुष्ठानफलकत्वं वेदस्य जानन्तो नित्यत्वं वा तदध्ययनस्य जानन्तो न तदध्ययनप्रयोजनं पृच्छन्तीति न कदाचिदपि वेदाध्ययनप्रयोजनोपदेश इति तात्पर्यम् ॥ (भाष्ये)—**न तथेति** । किं तु विपरीतमित्यर्थः । भाष्ये—**आचार्यपदेन** शास्त्राध्यापको भाष्यकृदेव विवक्षितः ॥ **इदं शास्त्रमिति** । प्रयोजनान्वाख्यानमित्यर्थः ॥

(अनुबन्धचतुष्टयोपसंहारभाष्यम्)

उक्तः शब्दः । स्वरूपमप्युक्तम् । प्रयोजनान्यप्युक्तानि ॥

(उद्द्योतः) भाष्ये—**उक्तः शब्द इति** । **'लौकिकानां वैदिकानां च'** इत्यनेन विषयभूतः शब्द उक्त इत्यर्थः ॥ **स्वरूप-**

स्मृत्या वेदवेदाङ्गाध्ययनयोः सकारणता लभ्यते तथाप्यार्थत्वाविशेषाद् व्रीहियववद् विकल्प इति बोध्यम् ॥ **व्याकरणं**-प्रागुक्तम् ॥

[प्रदीपे] द्वेशब्दानर्थक्यं परिहरति—कैयटे—**अद्यत्वे इति** ॥

[प्रदीपे] शेषं पूरयति-कैयटे—**विवाहादाविति** ॥ तत्रोत्सुकाः सन्त इत्यर्थः ॥

[उद्द्योते] ननु—किंचिदिष्यन्त एव पूर्वपक्षः । ओमित्यादि परिहारः—इति । तत्र समञ्जसमित्याशयेनाह—उद्द्योते—**भाष्ये उत्तरमिति** ॥

[उद्द्योते] तत्र चौलान्तसंस्कारोत्तरं तदभावादाह—[उ० २ यप०] **उपेति** ॥

[उद्द्योते]—उद्द्योते—**नादादीति** । भाष्यस्थनादपदमुपलक्षणं विवारादीनामिति भावः ॥ यद्यपि सर्वाङ्गाध्ययनं पूर्वम्, तथापि वैदिकशब्दोपदेशे व्याकरणशिक्षाऽन्योपयोगाभावेन फलितार्थमाह—[३ यप०] **तेनाधीति** ॥ वर्णोच्चारणप्रकारस्य स्थानादेः प्रकृत्यादिविभागेन तदर्थरूपकथनस्य च तयोः सत्त्वादिति भावः ॥ नन्वङ्गाध्ययनकाले बाल्यात् प्रयोजनप्रश्नासामर्थ्याद् वेदाध्ययनकाले प्रौढत्वात् तत्सामर्थ्येऽपि कुतो न तदुपदेश इत्यत आह—**ते तदानीमपीति** ॥ वेदाध्ययनकाले प्रौढतायामपीत्यर्थः ॥ अपिनेदानीं बाल्यकालसमुच्चयः ॥ अत एवाग्रे न कदाचिदपीत्युक्तिः ॥ [४ धप०] **फलकत्वम्**-अर्थज्ञानद्वारा ॥

[उद्द्योते] 'तद्यत्वे' इति रत्नकृद्धृतभाष्यपाठासांगत्यं ध्वनयन्नाह—उद्द्योते—**किंस्विति** । अल्पायुष्ट्वात्प्रधानीभूतवेदाध्ययनोत्तरमङ्गाध्ययनमित्यर्थः ॥

[उद्द्योते] अन्यस्यासंभवादाह—[उ० ७ मप०]—**भाष्ये आचार्येति** ॥ तत्रे बीजमाह—**शास्त्रेति** ॥ **इदं शास्त्र**मित्यनेन प्रागुक्तव्याकरणपरामर्शे तद्व्याख्यानस्यानुत्तरत्वादुत्तरग्रन्थानुरोधाच्च तस्यार्थमाह—[उ० ८ मप०] **प्रयोजनान्वाख्यानमिति** । शास्त्रं व्याकरणमिदं सप्रयोजनत्वादध्येयमिति कथयतीति भाष्यार्थ इत्यर्थः ॥

[भाष्ये] अथ पाणिनीयशास्त्रस्यावश्यकत्वप्रतिपादनाय परमतं निरसितुमाक्षेपपूर्वकतात्पर्यं वक्तुमुक्तं संगृह्णाति—भाष्ये—**उक्तः शब्द इत्यादि** ॥

[भाष्ये] भाष्ये—**प्रयोजनेति** । **'कानि'** इत्यादिना **'उक्तः'**—इत्यन्तः प्राक्तनग्रन्थेनेति भावः ॥

[उद्द्योते]—उद्द्योते—**विषयेति** । लौकिको वैदिकश्च सर्वः शब्दः शास्त्रविषय इत्युक्तमिति भावः ॥ **त्यादिनेति** । ध्वनिः शब्द इत्यन्तेनेति भावः ॥

[उद्द्योते] ननु **शब्दानुशासन**मित्येव सिद्धे निष्प्रयोजनोऽयं संग्रहोऽत आह—उद्द्योते—**अयमुपेति** ॥ **ग्रन्थस्य**-पूर्वोक्तस्य । पूर्वान्वयीदम् ॥ **विषयेति** । **'अथ शब्दानुशासनम्'** इति शास्त्रारम्भप्रतिज्ञापरवाक्यसूचितमित्यर्थः । शिष्यसौकर्यार्थमिति भावः ॥ **तेनैव**-तयोरभिधानेनैव ॥ **उक्तावीति** । उक्तप्रायावित्यर्थः ॥ **पृथगिति** । साक्षादित्यर्थः ॥ वक्ष्यमाणप्रविवेकाय **'उक्तः'** इत्यादिनोक्तसंकीर्तनमिति बोध्यम् ॥

[भाष्ये] तदेतद्ध्वनयन्ननुबन्धचतुष्टयसत्त्वादारब्धव्ये शास्त्रे तत्प्रकारनिरूपणायाह—भाष्ये—**शब्देति** ॥ **इदानीं**—तच्चतुष्टयनिश्चयकाले ॥ **कर्तव्यमिति** । अस्य **'इति सिद्धम्'** इति शेषः ॥ तत्र सामान्येन प्रश्नं प्रागुक्तं करोति—**कथमिति** ॥ एकैकोपदेशे न कृतकृत्यधीः, उभयोपदेशे गौरवमित्यशक्यमनुशासनमिति भावः ॥ स एव विशिष्याह—**किं शब्दोपेति** ॥ **आहोस्वित्**—अथवा ॥

[प्रदीपे] ननु गौरवात्तृतीयपक्षो दुर्वचोऽत आह—कैयटे—**हेयोपेति** ॥

[भाष्ये]—भाष्ये—**कृतं स्यादिति** । विनिगमनाविरहात् तेन सर्वेष्टं सिद्धं स्यादित्यर्थः ॥

[भाष्ये]—दृष्टान्तेनैतदुपपादयति—भाष्ये—**तद्यथेति** ॥ यथेत्यर्थः ॥ यद्वा तेन स गम्यते यथा तथा तदित्यर्थः ॥ यद्वा तत् तादृशं यथेत्यर्थः ॥ **नियमेनेति** । रागतः प्राप्तस्य भक्ष्यस्य पुनर्विधिनेत्यर्थः ॥ तस्यार्थिकत्वादाह—**गम्यत इति** ॥ एवमग्रेऽपि ॥ एतदेव स्फुटयति—**पञ्चेति** ॥

[भाष्ये]—एवमुपादेयनियमेनार्थात्तदन्यनिषेधप्रतीतौ दृष्टान्तमुक्त्वा निषेध्यनियमेनार्थात्तदन्योपादेयप्रतीतौ दृष्टान्तमाह—भाष्ये—**अभक्ष्येति** । तदुपदेशेनेत्यर्थः ॥

मपीति । 'अथ गौः' इत्यादिना ॥ अयमुपसंहारो ग्रन्थस्य, विषयप्रयोजननिरूपणमेतावता कृतमिति बोधयितुम् । तेनैव संबन्धाधिकारिणावुक्ताविति तौ पृथङ्नोक्तौ ॥

(इत्यनुबन्धचतुष्टयनिरूपणम्)

—ooo—

(अथ शास्त्रनिर्माणरीतिनिरूपणाधिकरणम्)

(प्रकारप्रदर्शकभाष्यम्)

शब्दानुशासनमिदानीं कर्तव्यम् । किं शब्दोपदेशः कर्तव्यः, आहोस्विदपशब्दोपदेशः, आहोस्विदुभयोपदेश इति ?

(प्रदीपः) **उभयोपदेश इति** । हेयोपादेयोपदेशे स्पष्टा प्रतिपत्तिर्भवति–इत्युभयोपदेश उद्भावितः ॥

(प्रकारनिर्द्धारकभाष्यम्)

अन्यतरोपदेशेन कृतं स्यात् । तद्यथा-भक्ष्यनियमेनाभक्ष्यप्रतिषेधो गम्यते । 'पञ्च पञ्चनखा भक्ष्याः' इत्युक्ते गम्यत एतत्—अतोऽन्येऽभक्ष्या इति ॥

अभक्ष्यप्रतिषेधेन च भक्ष्यनियमः । तद्यथा-'अभक्ष्यो ग्राम्यकुक्कुटः-अभक्ष्यो ग्राम्यसूकरः' इत्युक्ते गम्यत एतत्—आरण्यो भक्ष्य इति ॥

एवमिहापि ।

यदि तावच्छब्दोपदेशः क्रियते, गौरित्येतस्मिन्नुपदिष्टे गम्यत एतत्—गाव्यादयोऽपशब्दा इति ।

अथाप्यपशब्दोपदेशः क्रियेत, गाव्यादिषूपदिष्टेषु गम्यत एतत्—गौरित्येष शब्द इति ॥

(प्रदीपः) यद्यपि प्रतिपत्तिः स्पष्टा, गौरवं तु भवतीत्याह–**अन्यतरेति** । शब्दापशब्दयोरित्यर्थः । अन्यतरान्यतमशब्दावव्युत्पन्नौ स्वभावात् द्विबहुविषये निर्धारणे वर्तेते ॥ **पञ्चेति** । अर्थित्वाद्भक्षणं प्राप्तं पञ्चसु पञ्चनखेषु नियम्यमानं सामर्थ्यादन्येभ्यो निवर्तते । न त्वयं विधिः, अप्राप्तेरभावात् ॥

(उद्द्योतः) कियत्त्वमोऽन्यत्र इतराभावादाह—**अन्यतराभ्येति** । तत्र सुशब्दोपदेशः प्रयोगविध्यर्थोऽनुवादः । अपशब्दोपदेशस्तु प्रयोगप्रतिषेधार्थः ॥ **पञ्चनखा** इत्यस्य नियमत्वं दर्शयति—**अर्थित्वादिति** । **नियम्यमानं**–बोध्यमानमित्यर्थः ॥ ननु अस्य परिसङ्ख्यात्वात्कथं नियमत्वेन व्यवहारः ? अस्ति च नियमपरि-

[भाष्ये]—दार्ष्टान्तिके आह—भाष्ये—**एवमिति** ॥ गोशब्दादेः साधुत्वोक्त्यन्यथानुपपत्त्या तद्विरुद्धमसाधुत्वमन्येषामर्थादुक्तं भवतीति भावः ॥ एवमग्रेऽपि ॥

[प्रदीपे] कैयटे—**तीत्याहेति** । इत्यतः सिद्धान्त्येकदेश्याहेत्यर्थः ॥

[प्रदीपे] यत्तु—'अत्र **'शक्येन'** इति विशेषणं देयम् । अपशब्दोपदेशस्त्वसंभावित एव अशक्यत्वादिति स्वयमेवाग्रे उक्तत्वात्'—इति कृष्णः । तन्न, तदुक्तत्वैव तस्याप्यशक्यत्वस्योक्तत्वात् । तस्याग्रे प्रतिपाद्यत्वेनात्राविवक्षितत्वाच्च ॥ द्वितीयादिद्वयान्यतरत्वनिरासायाह—कैयटे—**शब्देति** ॥

[प्रदीपे]—कैयटे—**द्विबह्विति** । यथासंख्यमन्वयः ॥

[प्रदीपे]—कैयटे—**भक्षणमिति । युगपत् सर्वेषामित्यादिः**॥

[प्रदीपे]—अत एवाह—कैयटे **सामर्थ्यादिति** ॥

[उद्द्योते]—उद्द्योते–**इतराभावादिति** । सूत्रेण तेभ्य एव विधानादिति भावः ॥

[उद्द्योते]—नियमनस्याप्राप्तांशपरिपूरणफलकत्वेन विधिरूपेण प्रवृत्तेः कैयटे पुनरुक्त्यापत्तेश्चाह–उद्द्योते–**पुनरिति** ॥ तत्र शङ्कते—[५मप०] **नन्वस्येति** ॥ **अस्ति चेति** । अस्ति हीत्यर्थः ॥ [६ इप०] **पाक्षिकेति** । बहुव्रीहिः । अप्राप्तांशविशेषणम् ॥ **फलाच**—फला तु ॥ **अपिः**–परिसंख्यासमुच्चायकः ॥ **अभेदमिति** । नियमपरिसंख्ययोरिति भावः ॥

[उद्द्योते]—नियमविधेः सत्त्वाद् उत्तरानुरोधाच्चाह—उद्द्योते—[९ मप०]—**अपूर्वेति** ॥ ननु परिसंख्यायां शाब्दान्यनिवृत्तेः सत्त्वेन कथं तत्रार्थान्यनिवृत्तिरुक्ताऽत आह–**येष्विति** । तत्रेतरनिवृत्तेः शाब्दत्वात्पञ्चपञ्चनखातिरिक्ता भक्ष्यत्वाभाववन्त इति बोधादिति भावः ॥ **अस्यैव**–उक्तस्यार्थस्यैव ॥

पत्तिश्चेति । नियमेनेत्यस्योपदेशेनेत्येवार्थः संदर्भबलाल्लभ्यते ॥ शब्दान्तरेणानुपदेशादर्थतो लाभाच्च नायं मुख्य उपदेश इति नियमपदप्रयोगः ॥ ईदृश इतरनिवृत्तिफल उपदेश एव च नियमपदेनोच्यत इति भावः ॥ [१५ शप०] **युक्तोक्तिविरोधश्चेति** । तस्यास्तद्रीत्या शाब्दत्वेन फलत्वोक्तेरयुक्तत्वादिति भावः ॥ नन्वेषमन्येषां भक्षणे दोषो न स्यात् तद्भक्षणे प्रायश्चित्ताम्नानानर्थक्यं च स्यादतः स्वमते सर्वेष्टसिद्धिमाह—**सिद्धस्येति** ॥ **प्रमाणेति** । रागरूपेत्यर्थः ॥ अयं भावः—पञ्चेत्यादाववधारणविषयबुद्धिस्थवृत्तिपञ्चत्वसंख्यावति पञ्चपदस्य लक्षणा ॥ अवधारणं चात्र स्वान्यसंख्याधिकरणासंबन्धिसमभिव्याहृतप्रकारकज्ञानरूपम् । तेन —अन्येऽभक्ष्याः—इति फलतीति ॥ एवं चैवकारसमभिव्याहारेऽप्यार्थ्येव परिसंख्या । सा चोक्तान्यत्र समभिव्याहृतपदार्थाभावरूपा ॥ शाब्दी त्वन्यत्र स्पष्टा ॥ तदाह—**एवेति** ॥ **सोऽपि** एवकारोऽपि ॥ विरोधं परिहरति—[१८ शप०] **अन्ययोगेति** ॥

[उद्द्योते] तत्र नियमत्वाभावादाह—उद्द्योते [२ यप०] **भक्ष्यानुमतिरूप उपदेश इत्यर्थ इति** ।

[भाष्ये] अपशब्दोपदेशस्य गुरुत्वं व्यक्तीकर्तुं पृच्छति—भाष्ये—**किं पुनरिति** ॥ **ज्याय इति** । उपदिष्टमित्यर्थः ॥ एवं च कैयटोक्तार्थः फलित इति भावः ॥

[प्रदीपे]—प्रकर्षमुपपादयन्नाह कैयटे—**उभयोपेति** ॥ **द्वावपीति** । प्रत्येकमिति भावः ॥

[भाष्ये] **पदेश इति** । ज्यायानिति शेषः । तेषामल्पत्वान्नियतत्वेन प्रयुक्तत्वाच्चेति भावः ॥ एतदेवोपपादयति—**लघीयानित्यादिना** । अत्रोभयत्रेयसुन् प्राग्वत् ॥ न केवलं लाघवमेव शब्दोपदेशे, किंत्वावश्यकताऽपीत्याशयेनाह—**दृष्टान्वेति** ॥ इष्टजनकान्वाख्यानमपि निश्चयेन भवतीत्यर्थः ॥

संख्ययोर्भेदः । पाक्षिकाप्राप्तिकाप्राप्तांशपरिपूरणफलो नियमः । अन्यनिवृत्तिफला च परिसंख्या–इति चेत्, न । नियमेऽप्यप्राप्तांशपरिपूरणरूपफलबोधनद्वाराऽर्थान्यनिवृत्तेः सत्त्वेन अभेदमाश्रित्योक्तेः ॥ विधिरिति । अपूर्वविधिरित्यर्थः ॥ ये तु पञ्चपदस्य तदतिरिक्ते लक्षणा, भक्ष्यपदस्य चाभक्ष्ये सा–इति वदन्ति तेषां पदद्वये लक्षणागौरवम् । अस्यैव नियमत्वेन 'भक्ष्यनियमेनाभक्ष्यप्रतिषेधो गम्यते' इति भाष्यविरोधश्च । नियमपदस्य तद्बोधके लक्षणायां सैव दोषः, अक्षरास्वारस्यं च । 'नियम्यमानं भक्षणं सामर्थ्यादन्येभ्यो निवर्तते' इति कैयटासंगतिश्च । दृष्टान्तदार्ष्टान्तिकयोरत्यन्तवैषम्यापत्तिश्च । 'अन्यनिवृत्तिफला परिसंख्या' इति अभियुक्तोक्तिविरोधश्च । सिद्धस्य पुनर्विधानात्प्रापकप्रमाणस्य तदितराविषयत्वरूपसङ्कोचकल्पनम् । तेनान्येषां भक्षणाभावस्तद्भक्षणे प्रायश्चित्तं च सिध्यति । एवसमभिव्याहारे सोऽपि स्फुटमस्यार्थस्यैव द्योतकः । अन्ययोगव्यवच्छेद एवकारार्थ इति तु सामान्यप्रमाणसंकोचफलितमर्थमादाय नेयम् ॥ भक्ष्यनियम इति । भक्ष्यानुमतिरूप उपदेश इत्यर्थः ॥

(प्रकारविशेषजिज्ञासाभाष्यम्)

किं पुनरत्र ज्यायः ?

[प्रदीपे]—तदाह—कैयटे—साधुशब्देति । सर्वत्रेत्यादिः ॥ धर्मेति । अध्येत्रध्यापकयोर्भूयसा धर्मेण योग इत्यर्थः ॥ तथाच तेऽवश्यं ज्ञेया इति तदुपदेशे इष्टसिद्धिरिति भावः ॥ इष्टानां सुशब्दानां साक्षाज्ज्ञानं निश्चयेन भवतीति भाष्यार्थाशयेनाह—[२ यप०] अथवोपेति ।

[भाष्ये]—एवं तेन शब्दोपदेशे कर्तव्यत्वेन व्यवस्थापिते तदुपदेशेऽप्यशक्यत्वं प्रतिपादयितुं प्रकारविशेषजिज्ञासया पृच्छति—भाष्ये—अथैतस्मिन्निति । लघुभूते आवश्यके चेत्यर्थः ॥ शब्दोपदेशे सतीति । कर्तव्यत्वेन व्यवस्थापिते इत्यादिः ॥

[भाष्ये]—प्रतिपदेति । पदस्य पदस्य पाठ इत्यर्थः । अत एव प्रष्टैव तत्स्वरूपमाह—गौरश्व इति ॥

[उद्योते]—अनन्वयवारणायाह—उद्योते—प्रतीति ॥

[भाष्ये]—नेत्याहेति । प्राग्वत् ॥ ('नेत्याह । द्रव्यं नाम तत्' इति भाष्यव्याख्यायामुक्तवत्)

[भाष्ये]—इदमेव विशदयितुं श्रुतिमुदाहरति भाष्ये—[५ मप०] एवंहीति ॥

[भाष्ये]—भाष्ये दिव्यमिति । मानुषं वर्षं दिव्यमहोरात्रम्, तेन मानेन दिव्यं वर्षसहस्रं बोध्यम् । 'कालाध्वनोः–' इति द्वितीया ॥

[भाष्ये] भाष्ये—'जगामेति' इति पाठः ॥ विशिष्टवक्तृश्रोतृकालानां समवधानेऽपि पुरा समाप्तिर्नाभूत् किं पुनर्वाच्यम् 'संप्रति तेषां हीनत्वेऽपि सा' इत्यभिप्रेत्य व्याचष्टे—बृहस्पतिश्चेति । चकारौ–साधनसाहित्यवाचिनावाधुनिकप्रवक्त्राध्येतारौ व्यतिरेचयतः ॥ किं पुनरद्यत्वे इति । अस्मिन्कालेऽन्तं गमिष्यतीति किंपुनर्वक्तव्यमित्यर्थः, पूर्वान्वयीदम् ॥ ननु रसायनादिनेदानीमपि मनुष्याणां बहुकालजीवित्वात्सा सत्स्यतीत्यत आह—यः सेति ॥

(प्रदीपः) किं पुनरिति । उभयोपदेशाद्गुरोर्द्वावपि प्रशस्तौ, तयोः को ज्यायानित्यर्थः ॥

(निश्चितपक्षदर्शकभाष्यम्)

लघुत्वाच्छब्दोपदेशः । लघीयाञ्छब्दोपदेशः । गरीयानपशब्दोपदेशः । एकैकस्य शब्दस्य बहवोऽपभ्रंशाः । तद्यथा–गौरित्यस्य शब्दस्य गावी गोणी गोता गोपोतलिका–इत्येवमादयोऽपभ्रंशाः । इष्टान्वाख्यानं खल्वपि भवति ॥

(प्रदीपः) इष्टेति । साधुप्रयोगाद्धर्मावाप्तेरित्यर्थः । अथवा–उपादेयोपदेशात्साक्षात्प्रतिपत्तिर्भवतीति भावः ॥

(आक्षेपभाष्यम्)

अथैतस्मिञ्छब्दोपदेशे सति किं शब्दानां प्रतिपत्तौ प्रतिपदपाठः कर्तव्यः—गौरश्वः पुरुषो हस्ती शकुनिर्मृगो ब्राह्मण इत्येवमादयः शब्दाः पठितव्याः ?

(उद्योतः) भाष्ये 'प्रतिपत्तौ' इत्यस्योपायभूत इति शेषः ॥

(समाधानभाष्यम्)

नेत्याह । अनभ्युपाय एष शब्दानां प्रतिपत्तौ

प्रतिपदपाठ इत्यस्य मध्यमणिन्यायेनात्राप्यन्वयः ॥ सर्वथा–अत्यन्तम् ॥ सर्वचिरमिति पाठे सर्वेभ्यश्चिरमिति 'सुप्सुपा' इति समासः । वर्षशतमिति । षष्ठीतत्पुरुषः ॥ द्वितीया प्राग्वत् ॥ इदानीं रसायनादिसिद्धेरभावादिति भावः ॥

[भाष्ये]—[७मप०] प्रकारैः–प्रक्रियते व्यवच्छिद्यतेऽनेनेति–प्रकारः–सामान्यस्य भेदको विशेषः ॥ विद्यतेऽनयेति–विद्या, उपयुक्ता–फलवती ॥ क्वचित् 'उपयुज्यते' इति पाठः ॥ अत एवोद्योतेऽग्रे तथोक्तम् ॥

[भाष्ये]—तानेवाह—भाष्ये—[८ मप०] आगमेत्यादि ॥

[भाष्ये] व्यवहारैरित्यस्य यज्ञाद्यनुष्ठानाध्यापनकालेनेत्यर्थः ॥

[भाष्ये]—ततः किमत आह—भाष्ये [९ मप०] तत्र चेति । तेषां कालानां मध्ये ॥ अस्य–वक्तुः श्रोतुश्च ॥ आगमकालेनैव–कृत्स्नेत्याद्यर्थः ॥

[भाष्ये]—उपसंहरति भाष्ये—[११ शप०] तस्मादिति । यतः कतिपयशब्दज्ञाने न सर्वज्ञानादिसिद्धिस्तत इत्यर्थः ॥

[प्रदीपे]—ननु कथमर्थवादेनानभ्युपायत्वमत आह कैयटे प्रतिपदेति । अशक्यत्वद्वारेति भावः ॥ प्रतिपादयितुं–प्रतिपादयतः ॥

[प्रदीपे]—शब्दानां पारमन्तमयते गच्छति येनेति व्युत्पत्तिर्बोध्या । रूढिस्तु प्रतिपदोक्तशब्दप्रतिपादकस्य ॥ तदाह—कैयटे शास्त्रेति ॥

[प्रदीपे]—कैयटे [५ मप०] अपिना समुदायपरिग्रहः ॥ [६ ७प०] घृतमात्रेकेति । औषधिसंबन्धिसारांशादिना संस्कृता घृतस्य या मात्रा परिमितिस्तदेकेत्याद्यर्थः ॥ [७ मप०] तथेहेति । शास्त्र इत्यर्थः ॥

[प्रदीपे]—कैयटे—[८ मप०] ग्रहणेति । अध्ययनेत्यर्थः ॥

प्रतिपदपाठः ॥ एवं हि श्रूयते—"बृहस्पतिरिन्द्राय दिव्यं वर्षसहस्रं प्रतिपदोक्तानां शब्दानां शब्दपारायणं प्रोवाच नान्तं जगाम" ॥ बृहस्पतिश्च प्रवक्ता, इन्द्रश्चाध्येता, दिव्यं वर्षसहस्रमध्ययनकालः, न चान्तं जगाम ।

किं पुनरद्यत्वे ? यः सर्वथा चिरं जीवति-वर्षशतं जीवति ।

चतुर्भिश्च प्रकारैर्विद्योपयुक्ता भवति—आगमकालेन, स्वाध्यायकालेन, प्रवचनकालेन, व्यवहारकालेनेति । तत्र चास्यागमकालेनैवायुः पर्युपयुक्तं स्यात् । तस्मादनभ्युपायः शब्दानां प्रतिपत्तौ प्रतिपदपाठः ॥

(प्रदीपः) बृहस्पतिरिन्द्रायेति । प्रतिपदपाठस्याशक्यत्वं प्रतिपादयितुमयमर्थवादः ॥ शब्दानामिति । 'शब्दपारायण'शब्दो योगरूढः शास्त्रविशेषस्य, तत्र 'प्रतिपदोक्तानां' इति विशेषणाभिधानाय गम्यमानार्थस्यापि 'शब्दानां' इत्यस्य प्रयोगः ॥ एकदेशोपयोगादपि लोके 'उपयुक्तं' इत्युच्यते । यथा—औषधसंस्कृतघृतमात्रैकदेशोपयोगे 'उपयुक्तं घृतं' इति व्यवहारः, तथेह न—इति प्रतिपादयति—चतुर्भिरिति । आगमकालः—ग्रहणकालः । स्वाध्यायकालः—अभ्यासकालः । प्रवचनकालः—अध्यापनकालः । व्यवहारो याज्ञे कर्मणि ॥

(उद्द्योतः) (भाष्ये)—अनभ्युपाय इति । तत्त्वं चाशक्यत्वेन, कृत्स्नाभिमतानभ्युपायत्वात् । तत्रार्थवादमाह—भाष्ये—बृहस्पतिरिति ॥ ननु 'शब्दानां' इति पुनरुक्तमत आह—योगरूढ इति ॥ अर्थपौनरुक्त्यमाशङ्क्य निराकरोति—तत्रेति ॥ ननु यावदेवाध्येष्यते तावदेवाभ्युपयुक्तं स्यादत आह—भाष्ये—चतुर्भिरिति ॥ उक्तमेव तदाशयमाह—एकदेशेत्यादि । विद्योपयोगाधारभूतानां कालानां विद्यां प्रत्यप्याधारत्वात् तस्य च करणत्वविवक्षायोऽशा । चतुर्षु कालेषु विद्योपयुज्यते—इति फलितोऽर्थः । तत्राद्ययोः 'विद्यार्थ्ययं बुद्धिमान्' इत्यादरपूर्वकमन्नवस्त्रादिलाभरूप उपयोगः । तृतीये—प्रतिष्ठा, सच्छिष्यलाभद्वाराऽर्थप्राप्तिः, सत्कारविशेषश्च । चतुर्थे—यज्ञाद्यनुष्ठानकालेऽपशब्दप्रयोगप्रयुक्तप्रायश्चित्ताभावः, कर्मसाङ्गता, दक्षिणालाभः, प्रतिष्ठा चेत्युपयोगः । तादृशश्चोपयोगः सर्वोऽध्ययन एव ॥ भाष्ये—पर्युपयुक्तमिति । समाप्तमित्यर्थः । 'पर्यवसन्नं' इति पाठान्तरम् । न चेष्टापत्तिः, विद्योच्छेदापत्तेः । कर्मसु प्रायश्चित्तविधिवैयर्थ्यापत्तेश्च ॥

(आक्षेपभाष्यम्)

कथं तर्हीमे शब्दाः प्रतिपत्तव्याः ?

(समाधानभाष्यम्)

किंचित्सामान्यविशेषवल्लक्षणं प्रवर्त्यम् । येनाल्पेन यत्नेन महतो महतः शब्दौघान् प्रतिपद्येरन् ॥

किं पुनस्तत् ?

उत्सर्गापवादौ । कश्चिदुत्सर्गः कर्तव्यः, कश्चिदपवादः ॥

(प्रदीपः) किंचिदिति । सामान्यविशेषौ यस्मिंस्तत्—सामान्यविशेषवत् । 'कर्मण्यण्', 'आतोऽनुपसर्गे कः' इत्यादि ॥

(उद्द्योतः) ननु तदात्मकत्वालक्षणस्य मतोरनुपपत्तिरत आह—सामान्यविशेषाविति । लक्षणं—शास्त्रमित्यर्थः ॥

(आक्षेपभाष्यम्)

कथंजातीयकः पुनरुत्सर्गः कर्तव्यः, कथंजाती-

स्वाधीनाक्षरावासीतिथावत् ॥ अभ्यासेति । गुणनेत्यर्थः ॥ मननेनेति यावत् ॥

[प्रदीपे]—तथाच व्यवहारशब्दस्य क्रत्वर्थपुरुषार्थकर्मादौ यथार्हमुपकार इत्यर्थः ॥ तदेतदभिप्रेत्याह—कैयटे [९ मप०] व्यवहारो याज्ञे कर्मणीति ॥

[उद्द्योते] अत एवाग्रे—अनभ्युपाय इत्युक्तं भगवता ॥

[उद्द्योते]—ननु लक्षणेन प्रकृत्यादिविभागेन तद्धेतुसंज्ञादिधीपूर्वकमेकस्य ज्ञानाद्गौरवम्, प्रतिपदपाठे तु तत एव तत्तच्छब्दोच्चारणेनैवायासेन तत्प्रतिपत्तेर्लाघवमिति कथं तस्यानभ्युपायत्वं भगवतोक्तमत आह—[उ० २ यप०] तत्त्वं चेति ॥ अशक्येति । आनन्त्यादिति भावः ॥

[उद्द्योते] तत्रेति । अनभ्युपायत्वे इत्यर्थः ॥

[उद्द्योते]—[३ यप०] पुनरुक्तमिति ॥ शब्दानामित्यनेन शब्दपारायणमित्यत्रत्यशब्दपदं पुनरुक्तमित्यर्थः ॥ शब्दपारायणमित्यत्रस्य शब्दशब्दस्याफलत्वमिति यावत् ॥

[उद्द्योते]—अर्थपौनरुक्त्यमिति । योगरूढ्यैव शब्दानां विषयत्वावगमादिति भावः ॥ अत एव गम्यमानेति कैयटेनोक्तम् ॥ [४ यप०] आशङ्क्येति । तदाशङ्कां हृदि निधायेत्यर्थः ॥ तत्रेतीति । श्रुतावित्यर्थः ॥

भावः ॥—युक्तं स्यादिति । तावानेवाभ्युपयोगो भविष्यतीत्यर्थः ॥ तथाच किं समाप्त्येति भावः ॥ स्वेन विरोधं परिहरति [६ छप०] उक्तमेवेति ॥ तदाशयं—तथा भाष्योक्तहेतुभूतं सदृष्टान्तमाशयम् ॥

[उद्द्योते]—नन्वेवमपि कथं विद्यां प्रति कालस्य प्रकारत्वम्, तस्योपयोगाधारत्वेऽपि विद्याऽनाधारत्वादत आह—उद्द्योते [६ छप०] विद्योपेति । प्याधारत्वादिति । तां प्रति प्रकारताश्रयणम्—इति शेषः ॥ क्वचित्तथा पाठ एव ॥ नन्वेवं तृतीयानुपपत्तिरत आह—[७ मप०] तस्य चेति । आधारस्य चेत्यर्थः ॥ तत्फलितमाह—[८ मप०] चतुर्ष्विति ॥

[उद्द्योते]—प्रवचनस्य व्यवहारत्वेऽपि अर्थानुष्ठानवत्त्वोभयार्थत्वम्, किंतु पुरुषार्थत्वमेवेति पृथगुक्तिः ॥ अत्राद्ययो…… नत्वम्, अन्त्ययोः फलार्थत्वेनेति विवेकः ॥ कालग्रहणं कालस्यान्यत्वोक्तिप्रस्तावात् ॥ तदेतदभिप्रेत्याह—[उ० ८ मप०] तत्राद्ययोरिति । चतुर्णां मध्ये, आगमस्वाध्यायकालयोरित्यर्थः ॥ पूर्वकमिति । परैर्दानाद्यर्थेति इति शेषः ॥ यद्वा तत्पूर्वकत्वं दानद्वारेति यथाश्रुतमेवास्तु उपयोग इति भावः ॥ एवमग्रेऽपि ॥ [१० मप०] विशेषश्चेति । सुकृतविशेषोऽपि बोध्यः ॥ 'विद्याया उपयोगः' इत्यस्यानुषङ्गः ॥

यकोऽपवादः ?

(उद्योतः) भाष्ये-कथंजातीयक इति । केन प्रकारेणेत्यर्थः । एतेनैवंजातीयकेन शास्त्रेण सुशब्दोपदेशप्रवृत्तिः पाणिनेरुचितेति सूचितम् ॥

(समाधानभाष्यम्)

सामान्येनोत्सर्गः कर्तव्यः । तद्यथा—"कर्मण्यण्" ।

तस्य विशेषेणापवादः । तद्यथा—"आतोऽनुपसर्गे कः" ॥

—:o:—

(जातिव्यक्तिपदार्थनिर्णयाधिकरणम्)

(आक्षेपभाष्यम्)

किं पुनराकृतिः पदार्थः, आहोस्विद् द्रव्यम् ?

(समाधानभाष्यम्)

उभयमित्याह ॥

कथं ज्ञायते ?

उभयथा ह्याचार्येण सूत्राणि पठितानि । आकृतिं पदार्थं मत्वा—"जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम्" इत्युच्यते ।

द्रव्यं पदार्थं मत्वा-"सरूपाणाम्—" इत्येकशेष आरभ्यते ॥

(प्रदीपः) सकलशास्त्रव्यवस्था-एकतरपक्षाश्रयणे न सिध्यतीति पक्षद्वयाश्रयणं प्रश्नपूर्वकं करोति-**किं पुनरिति** । आकृतिपक्षे केवल आश्रीयमाणे **'सरूपद्वतो विप्रतिषेधे-'** इत्यादि नोपपद्यते, केवलेऽपि व्यक्तिपक्षे **'पुनःप्रसङ्गविज्ञानात्'** इत्यादि न घटेत । तस्माल्लक्ष्यसिद्धये क्वचित्प्रदेशे कश्चित्पक्षः परिगृह्यते । तत्र **जातिवादिन आहुः**—जातिरेव शब्देन प्रतिपाद्यते, व्यक्तीनामानन्त्यात्संबन्धग्रहणासंभवात् । सा च जातिः सर्वव्यक्तिष्वेकाकारप्रत्ययदर्शनादस्तीत्यवसीयते । तत्र गवादयः शब्दा भिन्नद्रव्यसमवेतां जातिमभिदधति । तस्यां प्रतीतायां तदावेशात्तदवच्छिन्नं द्रव्यं प्रतीयते । शुक्लादयः शब्दा गुणसमवेतां जातिमाचक्षते । गुणे तु तत्संबन्धात्प्रत्ययः, द्रव्ये संबन्धिसंबन्धात् । संज्ञाशब्दानामप्युत्पत्तिप्रभृत्याविनाशात् पिण्डस्य कौमारयौवनाद्यवस्थाभेदेऽपि स एवायमित्यभिन्नप्रत्य-

आगमकालादारभ्यासमाप्तिपर्यन्तं **अस्य नैव आयुः पर्युपयुक्तं** पर्याप्तं स्यादित्यर्थः' इति कश्चित् । पाठान्तरानुरोधेन समाप्तमित्येवार्थ इति ध्वनयन्नाह—[उ० १४ शप०] **पर्यवेति** ॥ **विच्छेदेति** । फलाभावादिति भावः ॥ अनुष्ठानाभावादाह—**कर्मस्विति** ॥

[भाष्ये]—पुनः स एव पृच्छति—भाष्ये—**कथं तर्हीति** ॥ गौरश्व इत्यादयः स्वरूपेणापि ये ये दुर्ज्ञानास्ते कथं लक्षणेनानुगन्तुं शक्या इत्यर्थः ॥

[भाष्ये]—उत्तरमाह सिद्धान्ती—**किंचिदिति** । लघुभूतमित्यर्थः ॥

[भाष्ये]—ननु तत्प्रवर्तनेऽपि किं स्यादत आह भाष्ये-**येनेति** । **अल्पेन**-लघुभूतेन ॥ **यत्नेन**-उपायेन । यत्नसाध्यत्वाल्लक्षणं-शास्त्रं यत्नशब्देनोच्यते **येन शास्त्रेण** ॥ **महतो महत इति** । वीप्सार्था द्विरुक्तिः, द्वितीयाबहुवचनान्तावेतौ शब्दसमूहविशेषणे ॥ यद्वा—आद्यः पञ्चम्यन्तः, विशालादपि विशालाञ्शब्दसमूहानित्यर्थः ॥

नन्वेवमस्यतौ सिजङोः सामान्यविशेषलक्षणाभ्यामनिष्टरूपद्वयापत्तिः, 'इरितो वा' इति वापदानर्थक्यं चेत्याशयेन पृच्छति—**किं पुनस्तदिति** । शास्त्रीयसामान्यविशेषयोः स्वरूपं किं पुनरित्यर्थः ॥ तौ कीदृशाविति यावत् ॥ यथा विशेषेण परामर्शस्तथा प्रतिपादयितव्यम् ॥

उत्तरमाह—**उत्सर्गेति** । तथाचापवादविषयपरिहारेण कौण्डिन्ये दधितक्रयोरिव नास्यतौ रूपद्वयम्, नापि तद्वैयर्थ्यमिति भावः ॥ तत्फलितमाह—**कश्चिदिति** । योग इत्यर्थः ॥ शास्त्रे इति भावः ॥ **कर्तव्य** इत्यस्याग्रेऽनुषङ्गः ॥

[प्रदीपे]—सामान्यविशेषशब्दौ सूत्रपराविति तयोः क्रमेण स्वरूपे भाष्योक्ते एवाह कैयटे—**कर्मेति** । आदिना **'कर्तरि शप्'** **'रुधादिभ्यः श्नम्'** इत्यादिपरिग्रहः ॥

[उद्योते]—**तदात्मकत्वादिति** । सामान्यविशेषस्वरूपत्वादित्यर्थः ॥ नन्वेवं लक्षणमित्यनुपपन्नमत आह—**शास्त्रमिति** । अष्टाध्यायीरूपमित्यर्थः ॥

[भाष्ये] तयोरुदाहरणे प्रतिपादयितुं विशेषेण पृच्छति—**कथमिति** ॥ प्रकारमात्रे थमुः, तद्वति जातीयर्-इति-अत्र जातीयरैव निर्वाहेऽपि सामान्योपक्रमाच्छिंशपा वृक्ष इतिवत्प्रयोगः ॥

[उद्योते]—**उक्तार्थाना**मित्यस्यानित्यत्वं सूचयितुमेवं प्रयोग इति कश्चित् । तदेतदभिप्रेत्याह—उद्योते—**केनेति** ॥ **शास्त्रेण**-अनेन ॥

[भाष्ये]—उत्तरमाह—भाष्ये—**सामेति** ॥ क्वचित् **'सामान्ये'** इति पाठः ॥ तत्र विषयसप्तमीति कृष्णः । तृतीयार्थे सप्तमीत्युचितम् । करणस्याधिकरणत्वविवक्षया सेति यावत् ॥

[भाष्ये]—**आकृतिः पदार्थ इति** । उत्सर्गापवादलक्षणगतानां पदानामिति भावः ॥

[भाष्ये]—तदाह सिद्धान्ती भाष्ये—**उभयमिति** । इत्याहेति पूर्ववत् ॥ तथाच क्वचिदुत्सर्गापवादलक्षणयोस्तत्तत्पदानां जातिरर्थः क्वचित्तु व्यक्तिरिति लक्ष्यानुरोधेनोभयाश्रयेण शास्त्रं प्रवृत्तिमिति भावः ॥

उक्ताशयानभिज्ञो लक्षणैकचक्षुष्कः शङ्कते—**कथमिति** ॥ सूत्रकृता तथा शास्त्रं प्रणीतमिति केन प्रकारेण निश्चीयत इत्यर्थः ॥ तत्र प्रमाणं किमिति यावत् ॥

एकदेशी तदनुरोधेनैवोत्तरमाह—**उभयथेति** ॥ **हि**-यतः ॥ अन्यथानुपपत्त्या लब्धजातिपक्षसाधकव्यक्तिपक्षसाधकस्वरूपप्रकारद्वयेनेत्यर्थः ॥ **सूत्राणीति** । सूत्रे पठिते इत्यर्थः ॥ आर्षं बहुवचनम् ॥

[भाष्ये]—तदेवाह—भाष्ये-**आकृतिमिति** । यदि व्यक्तिरेवेत्येतत्सार्वत्रिकमिष्टं स्यात् तदा संपन्ना व्रीहय इत्यत्र व्यक्तिबहु-

यनिमित्ता डित्थत्वादिका जातिर्वाच्या । क्रियास्वपि जातिर्विद्यते, सैव धातुवाच्या । पठति-पठतः-पठन्ति-इत्यादेरभिन्नस्य प्रत्ययस्य सद्भावात्तन्निमित्तजात्यभ्युपगमः ॥ **व्यक्तिवादिनस्त्वाहुः**-शब्दस्य व्यक्तिरेवाभिधेया, जातेस्तूपलक्षणभावेनाश्रयणादानन्त्यादिदोषानवकाशः ॥

(उद्द्योतः) आकृतिपक्षे इति । तत्र उद्देश्यतावच्छेदकजात्याक्रान्ते क्वचिच्चरितार्थयोर्द्वयोः सत्प्रतिपक्षन्यायेन विरोधस्थले उभयोरप्यप्राप्तौ **'विप्रतिषेधे परम्'** इति विध्यर्थम्, न तु नियमार्थमिति **'सकृद्गतौ'** इति न सिध्यति । व्यक्तौ तु तत्तद्व्यक्तिविषययोरपि शास्त्रयोरचारितार्थ्यात्पर्यायेणोभयप्राप्तौ नियमार्थं तदिति **'पुनः प्रसङ्गेन'** इत्यादि न सिध्यतीत्यर्थः । इदं च **विप्रतिषेधसूत्रे** दूषयिष्यते ॥

तस्यां प्रतीतायामिति । शब्दशक्यत्वेन गृहीतायामित्यर्थः । एवं **'अभिदधति'** इत्यस्याभिधाविषयत्वेन गृह्णन्तीत्यर्थः ॥ **तदावेशात्**-तत्समवायात् ॥ **प्रतीयत इति** । अविनाभावाच्छब्दजन्यबोधविषयो भवतीत्यर्थः ॥ **प्रत्ययः**-ज्ञानम् ॥ **उपलक्षणभावेनेति** । शक्यतावच्छेदकत्वेनेत्यर्थः । तत्र तु न शक्तिरिति मञ्जूषायां प्रतिपादितम् ॥

[भाष्ये-**जात्याख्यायामिति** । व्यक्तौ पदार्थे 'संपन्ना व्रीहयः' इति व्यक्तिबहुत्वाद्बहुवचनं सिद्धमेवेति व्यर्थं तत्स्यात्-इति भावः ॥ **सरूपाणामिति** । आकृतेरेकत्वादेवैकशब्दप्रयोगोपपत्तौ तदुक्तिसंभवो व्यक्तिपक्ष एवेति भावः । न चाकृतिपक्षेऽपि 'अक्षाः' 'पादाः' इत्याद्यर्थं स आवश्यक इति वाच्यम् । तावतीषु कांचिदेकां जातिं स्वीकृत्य तस्या एव शब्दवाच्यत्वम्, परम्परयाऽत्र व्यक्तिप्रत्यय इति सरूपसूत्रे कैयटेनैव वक्ष्यमाणत्वात् । जातौ न जातिरिति परेषां दर्शनं, नास्माकमिति च तत्रोक्तम् ॥]

(शब्दनित्यत्वानित्यत्वविचारः)

(सन्देहदर्शकभाष्यम्)

किं पुनर्नित्यः शब्दः, आहोस्वित्कार्यः ?

(प्रदीपः) किं पुनरिति । विप्रतिपत्त्या संशयः । केचित्

स्त्वाद्बहुवचनं सिद्धमेवेति 'जात्याख्यायाम्' इति नारभेत, तदारम्भात्तु जातेस्तत्त्वमिति निश्चय इति भावः ॥

[भाष्ये]—**इत्येकशेष इति** । एकस्य शेषो येनेति बहुव्रीहिः । **सरूपाणामिति** रूप एकशेषविधायको योग इत्यर्थः ॥ यदि जातिरेवेति सार्वत्रिकमिष्टं तर्हि **सरूपसूत्रं** नारभेत, यत आकृतेरेकत्वादेवैकशब्दप्रयोगः, तेनैव च जात्यवच्छिन्नसकलव्यक्त्युपस्थितिसंभव इति नानेकव्यक्त्यभिधानायानेकशब्दप्रसङ्गः । तदारम्भात्तु व्यक्तेरपि तत्त्वमिति निश्चय इति भावः ॥

[प्रदीपे]—कैयटे—[१मप०] **श्रयण इति** । सप्तम्यन्तम् ॥ **पक्षद्वयेति** । लक्ष्यानुरोधेन व्यवस्थितेत्यादिः ॥ **प्रभेति** । अन्यदोषेत्यादिः ॥ प्रसङ्गादिति भावः ॥ **करोतीति** । सिद्धान्तीत्यादिः ॥ अर्थविशेषान्तर्भावेणैव साधुत्वस्य वक्ष्यमाणत्वात्तदर्थमिति भावः ॥

[प्रदीपे]—सकलशास्त्रव्यवस्थामाह कैयटे [३ यप०] **केवलेति** । अनेन व्यक्तिपक्षव्यावृत्तिः ॥ एवमग्रेऽपि ॥ **आदिना 'यद्बाधितं तद्बाधितमेव'** इत्यस्य परिग्रहः ॥ [४ थंप०] **केवलेऽपीति** । केवले व्यक्तिपक्षेऽपीत्यर्थः ॥ **आदिना 'सिद्धम्'** इत्यस्य परिग्रहः ॥

[प्रदीपे]—उत्तरार्थं वदन्नुपसंहरति —कैयटे—[५मप०] **तस्मादिति** । बुद्धिस्थाद्धेतोरित्यर्थः । सकलशास्त्रव्यवस्थाया अन्यतरपक्षाश्रयणेनासिद्धत्वादिति यावत् ॥ ज्ञापकपरवक्ष्यमाणभाष्यस्यायुक्तत्वं ध्वनयन्नाह—**लक्ष्येति** ॥ लक्ष्यानुरोध एव तदाश्रयणे शरणमिति भावः ॥

[प्रदीपे] प्रसङ्गादनयोः पक्षयोरुपपत्ती क्रमेणाह—कैयटे—[५ मप०] तत्रेत्यादिना ॥ तत्र-तयोः पक्षयोर्मध्ये ॥ **पाद्यते इति** । लाघवादिति भावः ॥ हेत्वन्तरमाह—**व्यक्तीनामिति** । व्यभिचाराच्चेत्यपि बोध्यम् ॥ तत्सत्त्वे मानमाह—**साचेति** । **प्रत्ययो** ज्ञानम् ॥ सामान्येनोक्तं स्पष्टार्थं विशिष्य चतुर्विधशब्देषु क्रमेणोपपादयति—[८मप०] **तत्रेति** । चतुर्णां शब्दानां मध्य इत्यर्थः ॥

[प्रदीपे] कैयटे [१२शप०] **संबन्धादिति** । प्रत्यय इत्यस्यानुषङ्गः । परम्परयेति भावः ॥ संज्ञास्थले पिण्डस्यैकत्वेन जात्यसंभवात्तत्र कथं निर्वाह इति मध्ये एव विमताशङ्कायां व्युत्क्रमेणादौ तत्रैवाह—[१२ शप०] **संज्ञेति** ॥ अत एवाह—… … … … … … … ॥ यद्वा—क्रमप्रतिपादने तात्पर्यादेवमुक्तिः । यद्वा-त्रयीपक्षे संज्ञाशब्दानां जातिशब्देऽन्तर्भावेन तत्र जातेः प्रसिद्धत्वात्क्रियासु तस्याः प्रतिपादनीयत्वादेवमुक्तिः ॥ अस्य **जातिर्वाच्येत्यत्रान्वयः** । **अपिः** पिण्डस्येत्यत्र योज्यः । एकस्यापि पिण्डस्य तस्मात्भेदे सतीत्यर्थः । **प्रत्ययेति** बहुव्रीहिः ॥ तत्र तत्सत्त्वे मानमाह—**पठतीति** । यत इत्यादिः ॥ [१७-शप०] **व्यक्तिरेवेति** । आनुभविकत्वादनुपपत्तिप्रतिसंधानं विना प्रतीयमानत्वाच्छाब्दान्वयस्य तत्रैव संभवाद्भ्रमकं विना तस्याः प्राधान्येनाप्रतीयमानत्वाच्च नानन्त्यादिदोषोऽत आह—**जातेस्त्विति** । अनुगताया इति भावः ॥

[प्रदीपे] [कै० १८ शप०] **आनन्त्यादीति** । **आदिना** गौरवव्यभिचारपरिग्रहः ॥

[उद्द्योते]—अनुपपत्तिप्रकारं क्रमेणाह—उद्द्योते—**तत्रेत्यादिना** ॥ **तत्र**-जातिपक्षे ॥ तत्र कार्यस्याबाधादाह—**उद्देश्येति** । **अपिर्मिथः समुच्चायकः** ॥ यद्वा विप्रतिषेधे इति नियमसमुच्चयः ॥ अप्राप्तिर्विध्यर्थत्वे निमित्तम् ॥ स्पष्टार्थमाह—[३ यप०] **नत्विति** । तुरुक्तवैलक्षण्ये ॥ [४ थंप०] **विषययोरपीति** । सप्तम्यन्तम् । तयोरपि सतोरित्यर्थः ॥ [५ मप०] **शास्त्रयोः**-विरोधाधारलक्ष्यविषययोः । यद्वा हेतुगर्भविशेषणम् । सकलव्यक्तिविषययोरपि शास्त्रयोरित्यर्थः ॥ निरपिपाठस्तु सुगम एव ॥ [५ मप०] **तदिति** । 'विप्रतिषेधे-' इति सूत्रमित्यर्थः ॥ **प्रसङ्गेत्यादीति** । **आदिना 'विज्ञानात्सिद्धम्'** इत्यस्य परिग्रहः ॥ **'आकृतीत्यादि—घटेत'** इत्यन्तकैयटासंगतिमाह—**इदं चेति** ॥

ध्वनिव्यङ्ग्यं वर्णात्मकं नित्यं शब्दमाहुः । अन्ये-वर्णव्यतिरिक्तं पदस्फोटमिच्छन्ति । वाक्यस्फोटमपरे संगिरन्ते । अन्ये तु-ध्वनिरेव शब्दः स च कार्यः, तद्व्यतिरेकेणान्यस्यानुपलम्भात्-इत्याचक्षते ॥

(उद्द्योतः) विप्रतिपत्त्येति । शब्दानां नित्यत्वे व्यर्थं व्याकरणशास्त्रमिति प्रश्नाशयः ॥ केचित्-मीमांसकाः ॥ वर्णात्मकमिति । पदवाक्ये च वर्णसमूहरूपे एवेति तदाशयः । अत्र मते 'एकं पठपदं'इत्याद्यनुपपत्तेराह—अन्ये-वैयाकरणाः ॥ अपरे-त एव मुख्याः । पदे वर्णानामिव वाक्ये पदानां कल्पितत्वात् तेषामर्थवत्त्वमपि काल्पनिकमिति वाक्यस्यैव शब्दत्वमिति तद्भावः ॥ अन्ये त्विति । वैशेषिकादयः ॥ ध्वनिरिति । स च वर्णावर्णात्मकत्वेन द्विविधः । एवं च कण्ठादिवच्छास्त्रमपि तस्य कारणमित्याशयः ॥

(पक्षनिर्द्धारकभाष्यम्)

संग्रह एतत्प्राधान्येन परीक्षितम्—नित्यो वा स्यात्कार्यो वेति । तत्रोक्ता दोषाः, प्रयोजनान्यप्युक्तानि । तत्र त्वेष निर्णयः—यद्येव नित्यः, अथापि कार्यः, उभयथाऽपि लक्षणं प्रवर्त्यमिति ॥

(प्रदीपः) संग्रह इति । ग्रन्थविशेषे ॥

(उद्द्योतः) संग्रहः-व्याडिकृतो लक्षश्लोकसंख्यो ग्रन्थ इति प्रसिद्धिः ॥ भाष्ये—उभयथाऽपीति । एवं च निष्फलोऽयं विचार इति भावः ॥ साधुत्वज्ञानायोभयथाऽपि शास्त्रमावश्यकमिति तात्पर्यम् ॥

(नित्यशब्दवादेऽपि शास्त्रस्य धर्मजनकताधिकरणम्)

(वार्तिकावतरणभाष्यम्)

कथं पुनरिदं भगवतः पाणिनेराचार्यस्य लक्षणं प्रवृत्तम् ?

(प्रदीपः) कथं पुनरिति । किमाचार्य एव स्रष्टा शब्दार्थसंबन्धानाम्, अथ स्मर्ता-इति प्रश्नः ॥

(उद्द्योतः) अथ पाणिनिसूत्रव्याख्यानभूतं वार्तिकमवतारयति—कथं पुनरिति । अत एवात्रैव पाणिनिनामग्रहणम् । एतेः पूर्वं तु सवार्तिकशास्त्रव्याख्यानप्रयोजनविषयप्रदर्शनपरो भाष्यकारस्यैव ग्रन्थ इति बोध्यम् ॥ शब्दार्थसंबन्धानामिति ।

[उद्द्योते] विशिष्टज्ञानजनकोपस्थितिरूपनिर्विकल्पस्मरणायाह—[उ० ७ मप०] शब्दशक्येति ॥ सिंहावलोकनन्यायेनैतदेकवाक्यतायै आह—एवमिति । एवमग्रेऽपि ॥ तद्वैशिष्ट्यादित्यर्थेन पौनरुक्त्यवारणायाह—[८ मप०] तत्समेति ॥ अत एव 'तत्संबन्धात्' इत्यग्रे वक्ष्यति कैयटः ॥ लक्षणादिवारणायाह—[९ मप०] अविनेति । व्याप्तेरित्यर्थः ॥

[उद्द्योते] शब्दोपात्तस्याप्युपलक्षणत्वस्य काकवदित्यादौ सत्त्वाच्चन्मतप्रवेशसत्त्वादाह [उ० १० मप०] शक्येति ॥ नन्वेतावतैव तस्या वाच्यत्वापत्तिरिति स दोष एवात आह—तत्र त्विति । शक्यतावच्छेदके त्वित्यर्थः ॥ अकार्यत्वेऽपि कार्यतावच्छेदकत्ववदशक्यत्वेऽपि शक्यतावच्छेदकत्वसंभवादिति भावः ॥

[उद्द्योते]—तदाह—उद्द्योते [१२ शप०] व्यक्ताविति ॥ इतीति । इत्यत्रेत्यर्थः ॥

[उद्द्योते] तदाह—[उ० १४ शप०] आकृतेरिति ॥ नारायणकौस्तुभाद्यनुरोधेन शङ्कते [१५ शप०] नचेति ॥ स इति । सरूपेतियोग इत्यर्थः ॥ तावतीषु-जातिषु ॥ वाच्यत्वमिति । स्वीक्रियतामिति शेषः ॥ नन्वेवं तदाश्रयजातिबोधेऽपि व्यक्तिबोधो न स्यादत आह—[१७ शप०] परम्परेति ॥ ननु जातौ न जातिरनवस्थापत्तेरत आह—[१८ शप०] जाताविति ॥ परेषां नैयायिकानाम् ॥ तत्रोक्तम्-कैयटेनैव ॥ अग्रे अग्रे तदनङ्गीकारेण नानवस्थेति भावः ॥ अत्र 'कैयटेनैव' इत्यनेन सूचितारुचिबीजं तु तत्रैणैव तत्र निर्वाह इति । वस्तुतस्तु लक्ष्यानुरोध एवात्र शरणम् । अत एवानयोः प्रत्याख्यानसंगतिः । अन्यथा भाष्ययोर्विरोधः स्पष्ट एव । ... न मञ्जरीत्येदं भाष्यम् ॥ सिद्धान्तरीत्या न भाष्यं । किंच यत्र वने वृक्षान्तरसत्त्वेऽपि पनसव्याप्तत्वं तत्र लक्षणया जातिपरत्वे पनसाः सन्तीति प्रयोगसिद्ध्यर्थं 'जात्याख्यायां-' इति सूत्रमावश्यकम् । अत एव वक्ष्यति सरूपसूत्रे वार्तिककृत्—*व्यर्थेषु च मुक्तसंशयम्* इति, इति बोध्यम् ॥

[प्रदीपे] संशयबीजमाह—कैयटे विप्रेति । विरुद्धकोटिद्वयोपस्थित्येत्यर्थः ॥

[प्रदीपे] विप्रतिपत्तिमेवाह—कैयटे केचिदित्यादिना ॥ वर्णात्मकमिति । पदवाक्ययोस्तदतिरिक्तत्वं नेत्यर्थः ॥

[प्रदीपे] कैयटे पदस्फोटमिति । नित्यं शब्दमित्यस्यानुषङ्गः ॥ एवमग्रेऽपि ॥

[उद्द्योते] प्रश्नबीजयोस्तात्पर्यमाह उद्द्योते—शब्देति ॥ शय इति । इति भाव इति शेषः ॥

[उद्द्योते] तदाह—उद्द्योते—पदेति ॥ अन्ये इति । अस्य इति शेषः ॥ रणा इत्यस्य 'इत्यर्थः' इति शेषः ॥ एवमग्रेऽपि ॥

[उद्द्योते] त एव-वैयाकरणा एव ॥ तेषां-पदानाम् ॥ वाक्यस्यैवेति । असत्यपदपदार्थविभागकस्येत्यादिः ॥ न्यूनतां परिहरति—सचेति ॥ एवञ्च-जन्यस्य तस्योक्तरीत्या द्वैविध्ये च ॥ कारणमिति । तथाचात्र पक्षे तदावश्यकत्वमिति भावः ॥

[भाष्ये] निष्फलोऽयं विचार इत्याशयेन सिद्धान्ती उत्तरमाह—भाष्ये—संग्रह इति । कैयटोक्तस्तदर्थः ॥

[भाष्ये] तत्र बहुधा परीक्षा कृता, अत्र तु शब्दानुशासनप्रस्तावात्तदुपजीवनमित्याशयेनाह भाष्ये—प्राधान्येनेति ॥ एतत्पदार्थमाह—नित्या वेति ॥ प्राधान्येनेत्यस्यार्थमाह—तत्रोक्ता इति । उभयत्रेत्यर्थः ॥ वर्णनित्यत्वे व्यापकस्य विकाराभावात् इकः स्थाने यण् न स्यात् । कार्यत्वे सच्छब्दानन्तर्यरूपसंहिताया अभावात् स न स्यादित्यादयो दोषा बोध्याः ॥ प्रयोजनेति । अनवयवस्य स्फोटस्य व्यञ्जकध्वनिधर्मेणान्वाख्यानम् । 'इको यणचि' इत्यादिना साधुत्वमात्रं क्रियत इत्यादिप्रयोजनानीत्यर्थः ॥ ननूभयत्र

शब्दाश्चार्थाश्च संबन्धाश्चेति द्वन्द्वः । एवं च किमपूर्वशब्दनिष्पादनद्वाराऽर्थविशेषसंबन्धनिष्पादकत्वं शास्त्रस्य, किं वा सिद्धशब्दार्थसंबन्धबोधकत्वमिति प्रश्नार्थ इति तात्पर्यम् ॥

(१ आक्षेपसाधकवार्तिकप्रथमखण्डम् ॥ १ ॥)

॥ * ॥ सिद्धे शब्दार्थसंबन्धे ॥ * ॥

(व्याख्याभाष्यम्)

सिद्धे शब्देऽर्थे संबन्धे चेति ॥

(प्रदीपः) **सिद्ध इति** । तत्र नित्यः **शब्दो** जातिस्फोटलक्षणो व्यक्तिस्फोटलक्षणो वा । कार्यशाब्दिकानामपि प्रवाहनित्यतया । **अर्थस्यापि** जातिलक्षणस्य नित्यत्वम् । द्रव्यपक्षेऽपि सर्वशब्दानामसत्योपाध्यवच्छिन्नं ब्रह्मतत्त्वं वाच्यमिति-नित्यता, प्रवाहनित्यतया वा । **संबन्धस्यापि** व्यवहारपरम्परयाऽनादित्वान्नित्यता ॥

(उद्द्योतः) **'सिद्धे शब्दार्थसंबन्धे'** इति वार्तिके समाहारद्वन्द्वात्सप्तमी । संबन्धश्च प्रत्यासत्त्या शब्दार्थयोरेव । त्रयाणामात्यन्तिकाविश्लेषप्रदर्शनाय समाहारनिर्देश इति बोध्यम् ॥ **व्यक्तिस्फोटेति** । सा पदवाक्यरूपा नित्यैवेति तद्भावः । एतच्चोपपादितं प्राक् ॥ **कार्यशाब्दिकानामिति** । 'कार्यशाब्दिकानाम्' इति त्वपपाठः, उत्तरपदवृद्धेर्दुर्लभत्वात् ॥ **असत्योपाधीति** । जातिरूपेत्यर्थः । जातिर्हि तन्मते आविद्यको धर्मविशेषः । यद्वा [रूपत्वेन धर्माणामेवाविद्याकार्यत्वेन] सर्वेषां धर्माणां ब्रह्मण्यध्यस्तत्वेन शुक्तिरजतादिस्थाने शुक्त्यादीनां विशेष्यत्ववत् सर्वत्राधिष्ठानभूतं ब्रह्मैव विशेष्यम्, विशेष्यमेव च द्रव्यमिति भावः ।

[यत्तु-व्यक्तीनामाविद्यकत्वेन तदवच्छिन्नं ब्रह्मैव जातिरिति, तन्न । अनेकव्यक्तीनामाविद्यकानां कल्पने गौरवात् । 'अपागादग्नेरग्नित्वम्' इत्यादि श्रुत्या जातेरेवानित्यत्वबोधनाच्च । अत एव जातेर्व्यवहारनित्यताम्-आकृतेः प्रवाहनित्यतामेवाग्रे वक्ष्यति भाष्यकृत् ।]

शब्दार्थयोर्नित्यत्वपक्षे तत्संबन्धस्य नित्यत्वेऽप्यनित्यत्वपक्षे कथं संबन्धस्य नित्यत्वमत आह—**संबन्धस्येति** । तयोरिव तस्यापि नित्यत्वमिति भावः ॥ शब्दार्थयोः संबन्धश्च शक्तिरूपं तादात्म्यमेवेत्यन्यत्र प्रपञ्चितम् ॥

(वार्तिकघटकसिद्धशब्दार्थनिरूपणभाष्यम्)

(आक्षेपभाष्यम्)

अथ सिद्धशब्दस्य कः पदार्थः ?

(प्रदीपः) सिद्धशब्दस्य नित्यानित्ययोर्दर्शनात्पृच्छति-**अथेति** ॥

(उद्द्योतः) भाष्ये—**सिद्धशब्दस्य कः पदार्थ इति** । अत्र पदार्थशब्दो रूढः । सिद्धशब्दसंबन्धी कः पदार्थः—इत्यर्थः ॥

(समाधानभाष्यम्)

नित्यपर्यायवाची सिद्धशब्दः ॥

कथं ज्ञायते ?

यत्कूटस्थेष्वविचालिषु भावेषु वर्तते । तद्यथा— सिद्धा द्यौः, सिद्धा पृथिवी, सिद्धमाकाशमिति ॥

(प्रदीपः) **नित्येति** । नित्यलक्षणस्यार्थस्य पर्यायेण वाचकः, तमेवार्थं कदाचिन्नित्यशब्द आह-कदाचित्सिद्धशब्द इत्यर्थः ॥ **कूटस्थेष्विति** । अविनाशिषु ॥ **अविचालिष्विति** । देशान्तरप्राप्तिरहितेषु ॥

(उद्द्योतः) **कूटस्थेष्विति** । कूटं=अयोघनस्तद्वत्तिष्ठन्ति ये तेषु, संसर्गिनाशेऽपि स्वयमनष्टेष्वित्यर्थः ॥ नन्वयोघनस्यापि तर्हि नित्यत्वं स्यादत आह—**अविचालिष्विति** । भाष्ये द्यावापृथिव्याद्यपि व्यावहारिकनित्यत्वाभिप्रायेण दृष्टान्तितम् । आकाशस्यापि व्यावहारिकनित्यत्वमेवाचार्याभिमतम् । एवञ्च तत्र रूढत्वान्नित्यवाचकस्यैव ग्रहणमिति भावः ॥

(आक्षेपभाष्यम्)

ननु च भोः कार्येष्वपि वर्तते । तद्यथा—सिद्ध ओदनः, सिद्धः सूपः, सिद्धा यवागूरिति । यावता कार्येष्वपि वर्तते, तत्र कुत एतत्-नित्यपर्यायवाचिनो ग्रहणम्, न पुनः कार्ये यः सिद्धशब्द इति ।

(प्रदीपः) **ननु चेति** । सिद्धशब्दात्क्रियानिष्पन्नोऽप्यर्थोऽवगम्यत इत्यर्थः ॥

कारणोक्तौ तयोरन्यतरानिश्चये शास्त्रं कर्तव्यमेवेति कथं निश्चयः ? किंचैवं सति कथमस्य विचारस्य निष्फलत्वमत आह—**तत्र त्विति** ॥ तत्रैवेत्यर्थः ॥ तत्रापीति पाठेऽप्येवमेव ॥ **यद्येव**-यद्यपि ॥ **उभयथेति** । पक्षद्वयेऽपि दोषाणां सुनिरसत्वादिति भावः ॥

[उद्द्योते] तस्यार्थमाह उद्द्योते—**व्याडीति** ॥ **संख्य इति** । लक्षश्लोकपरिमित इत्यर्थः ॥

[उद्द्योते] **एवं च**-तत्रोभयथा शास्त्रारम्भस्यावश्यकत्वोक्तौ च ॥ ननु तत्रावश्यकत्वरूपनिश्चयोक्तिरेवाद्यौ कथमत आह—**साधुत्वेति** ॥ **तात्पर्यमिति** । व्याडेरिति भावः ॥

अथ 'भगवतः' इत्युक्त्वा पूज्यत्वप्रतिपादनद्वारा वार्तिककृदपेक्षया सूत्रकारे श्रद्धातिशयः सूचितः । अत एव सूत्रसमर्थनपूर्वकं वार्तिकखण्डनं भगवान् करिष्यति ॥

[उद्द्योते] **अथेति** । सूत्रकृदाद्यनुक्तविषयार्थोपोद्घातिकनिरूपणानन्तरमित्यर्थः ॥ पाणिनिसूत्रसमूहव्याकरणशास्त्रस्य नियमार्थताप्रतिपादकमाद्यवार्तिकमित्यर्थः ॥

ननु शब्दार्थसंबन्धस्रष्टृत्वं कथमाचार्यस्य ? किं च ब्रह्माण्डस्य चयानन्यत्वेन पाणिनेस्तदन्तर्गतस्य तत्स्रष्टृत्वं कथम् ? अतः कैयटतात्पर्यमाह—**एवं चेति** ॥

यद्यपि द्वितीयपक्षाश्रयेणोत्तरत्वेन प्रवृत्तं नवपदात्मकमेकं वार्तिकम् **'सिद्धे शब्दार्थसंबन्धे लोकतोऽर्थप्रयुक्ते शब्दप्रयोगे शास्त्रेण धर्मनियमो यथा लौकिकवैदिकेषु'** इति । क्रियत इति त्वध्याहारः । शब्दार्थसंबन्धे नित्ये सति शब्दप्रयोगे च लोकतोऽर्थप्रयुक्तेऽर्थबोधनाय प्रसक्ते सति शास्त्रेण धर्मनियमः क्रियते, यथा लौकिकवैदिकेष्विति तदर्थः । तथापि 'लोकतः' इत्यस्य मध्यमणिन्यायेनोभयत्रान्वयेन खण्डशो वार्तिकं यथेष्टं व्याचक्षाणो द्वितीयपक्षाश्रयेणोत्तरत्वं प्रतिपादयन्नाद्यखण्डमाह—**सिद्धे इति** ॥

(समाधानभाष्यम्)

संग्रहे तावत्कार्यप्रतिद्वन्द्विभावान्मन्यामहे नित्यपर्यायवाचिनो ग्रहणमिति ।

इहापि तदेव ॥

(प्रदीपः) **संग्रहे तावदिति** । तत्र हि 'किं कार्यः शब्दोऽथ सिद्धः' इति पक्षद्वयविचारः कृतः । तत्र कार्यप्रतिपक्षार्थाभिधायी सामर्थ्यात्सिद्धशब्द इति स्थितम् । तत्समानतन्त्रत्वादिहापि तथैव युक्तमित्यर्थः ॥

(समाधानान्तरभाष्यम्)

अथवा सन्त्येकपदान्यप्यवधारणानि । तद्यथा—अब्भक्षो वायुभक्ष इति, अप एव भक्षयति—वायुमेव भक्षयतीति गम्यते ।

एवमिहापि—सिद्ध एव, न साध्य इति ॥

(प्रदीपः) **अथवेति** । एवशब्दप्रयोगे द्विपदमवधारणम्, द्योतकत्वेनैवशब्दस्यापेक्षणात् । यदा तु द्योतकमन्तरेण सामर्थ्यादवधारणं गम्यते तदा तत् एकपदमित्युच्यते ॥ तत्र 'सर्वे एवापो भक्षयन्ति' इत्यब्भक्षश्रुतिः सामर्थ्यान्नियममवगमयति—**अप एवेति** ॥ इहापि नित्यानित्यव्यतिरेकेण राश्यन्तराभावात्सिद्धशब्दोपादानान्नियमोऽवगम्यते—**सिद्ध एवेति** । कार्याणां तु पदार्थानां प्राक्प्रध्वंसावस्थयोः सिद्धता नास्तीति न ते सिद्धा एव ॥

(उद्द्योतः) ग्रन्थान्तरामालोचनेनेऽपि नियामकमाह—भाष्ये—**अथवेति** । एतेन तत्समानतन्त्रत्वाद्व्यक्त्येकपदार्थवादोऽपि तत्र स्यादित्यपास्तम् ॥ ननु 'एकपदानि' इत्युक्त्वा 'अब्भक्षः' इत्यस्य पदद्वयात्मकस्योदाहरणत्वमसङ्गतमत आह—**एवशब्देति** ॥ नियमप्रत्यायकसामर्थ्यं दर्शयति—**इहापीति** ॥ कार्यवाचिन एव ग्रहणाभावे मूलमाह—**कार्याणामिति** । प्राक्प्रध्वंसावस्थयोरिति पाठः । भाष्ये 'अप एव···इति गम्यते' इति वाक्ये इव समासेऽपि सामर्थ्यात् तदतिरिक्तभक्षणाभावो गम्यत इत्यर्थः ॥

(समाधानान्तरभाष्यम्)

अथवा पूर्वपदलोपोऽत्र द्रष्टव्यः—अत्यन्तसिद्धः—सिद्ध इति । तद्यथा—देवदत्तः—दत्तः, सत्यभामा—भामेति ॥

(प्रदीपः) **अथवेति** । कथं पुनर्देवदत्तशब्दे संज्ञात्वेन विनियुक्ते एकदेशः प्रयुज्यते, न ह्यसौ संज्ञात्वेन विनियुक्तः । न चैकदेशात्स्मर्यमाणस्य समुदायस्य वाचकत्वमुपपद्यते, प्रतीयमानस्य प्रत्यायकत्वासंभवादुच्चार्यमाणस्यैव वाचकत्वात् । एवं तर्ह्यनुनिष्पादिन्योऽवयवसरूपाः संज्ञा विनियोगकाले विनियुक्ता एव । लोपस्तु वर्णानां साधुत्वं मा भूदित्यन्वाख्यायते । इहापि नित्यानित्ययोर्निष्पन्नत्वाविशेषात्सिद्धश्रुतिरुपात्ता प्रकर्षं गमयति—**अत्यन्तसिद्ध इति** ॥

(उद्द्योतः) **अथवेति** । मनुष्यवृक्षाद्यपेक्षयाऽऽकाशादीनामप्यत्यन्तसिद्धत्वमिति भावः ॥ **प्रतीयमानस्येति** । एतदणुदित्सूत्रे उपपादयिष्यते ॥ **एवं तर्हीति** । एवमेव 'षट्पदं कलशपर्यायः' इत्यादिप्रयोगाः । अन्यथा 'पर्यायवाचि' इति प्रयोज्यं स्यात् ॥ विनापि प्रत्ययं पूर्वोत्तरपदयोर्लोप इति लोपविधायकं तर्हि किमर्थमत आह—**लोपस्त्विति** । **वर्णानाम्**—'दे'इत्यादीनाम् । तत्रापि क्वचित्पूर्वपदस्यैव—क्वचिदुत्तरपदस्यैव—क्वचिदुभयोरिति लोकव्यवहारेण निर्णयम् । एवं वर्णानां श्रवणाभावोऽपि तत एव निर्णेय इति तत्त्वम् ॥ **निष्पन्नत्वेति** । विद्यमानकालसंबन्धः—**निष्पन्नत्वम्** ॥

(समाधानान्तरभाष्यम्)

अथवा "व्याख्यानतो विशेषप्रतिपत्तिर्न हि संदेहादलक्षणम्" इति नित्यपर्यायवाचिनो ग्रहणमिति व्याख्यास्यामः ॥

(प्रदीपः) न्यायाद्वा नित्यत्वं शब्दादीनां स्थितमित्याह—**अथवेति** । न हि संदेहमात्रादलक्षणता भवति, पुनः प्रमाणान्तरेण निश्चयोत्पादात् ॥

(उद्द्योतः) ननु निर्युक्तिकं व्याख्यानमयुक्तं, विपरीतस्यापि संभवादत आह—**न्यायाद्वेति** । वृद्धव्यवहारादेव पदार्थसंबन्धानां नित्यत्वं संग्रहादौ स्थितमिति व्याख्यानतः सिद्धशब्देन तदेवोपात्तमित्यर्थः ॥

(आक्षेपभाष्यम्)

किं पुनरनेन वर्ण्येन । किं न महता कण्ठेन नित्यशब्द एवोपात्तः, यस्मिन्नुपादीयमानेऽसंदेहः स्यात् ?

(प्रदीपः) **वर्ण्येनेति** । प्रयत्नव्याख्यातव्येनेत्यर्थः ॥

(समाधानभाष्यम्)

मङ्गलार्थम् ॥

माङ्गलिक आचार्यो महतः शास्त्रौघस्य मङ्गलार्थं सिद्धशब्दमादितः प्रयुङ्क्ते । मङ्गलादीनि हि शास्त्राणि प्रथन्ते वीरपुरुषाणि च भवन्ति, आयुष्मत्पुरुषाणि चाध्येतारश्च सिद्धार्था यथा स्युरिति ॥

(प्रदीपः) **माङ्गलिक इति** । अगर्हिताभीष्टार्थसिद्धिः—मङ्गलं, तत्प्रयोजन आचार्यो माङ्गलिकः ॥ **प्रथन्त इति** । अध्ययनस्याविच्छेदात् ॥ **वीरपुरुषाणीति** । श्रोतॄणां परैरपराजयात् ॥ **आयुष्मत्पुरुषाणीति** । शास्त्रार्थानुष्ठाने धर्मोपचयादायुर्वर्धनात् ॥ **सिद्धार्था इति** । अध्ययननिर्वृत्तिरेव तेषां सिद्धिः ॥

(उद्द्योतः) **सिद्धिर्मङ्गलमिति** । तस्या मङ्गलत्वं च कार्ये कारणरूपोपचारादिति बोध्यम् ॥ **तत्प्रयोजनमस्य—इति** प्राग्वतीयठक् ॥ तत्र मङ्गलानुष्ठानप्रयोजनान्याह—भाष्ये—**मङ्गलादीनीत्यादिना** ॥ ग्रन्थे तन्निबन्धनस्य फलमाह—**अध्येतारश्चेत्यादिना** । आनुषङ्गिकमङ्गलसंपत्त्येत्यर्थः ॥ **अध्ययननिर्वृत्तिः**—तत्समाप्तिः ॥ **सिद्धिः**—सिद्धिविषयोऽर्थः ॥ **मङ्गलार्थमित्यनेनैत** एव वार्तिकप्रवृत्तिः सूचिता ॥

(समाधानभाष्यशेषभाष्यम्)

अयं खलु नित्यशब्दो नावश्यं कूटस्थेष्वविचालिषु भावेषु वर्तते ।

किं तर्हि ?

आभीक्ष्ण्येऽपि वर्तते । तद्यथा-नित्यप्रहसितो नित्यप्रजल्पित इति । यावता आभीक्ष्ण्येऽपि, तत्राप्यनेनैवार्थः स्यात्—"व्याख्यानतो विशेषप्रतिपत्तिर्न हि संदेहादलक्षणम्" इति । पश्यति त्वाचार्यो मङ्गलार्थश्चैव सिद्धशब्द आदितः प्रयुक्तो भविष्यति, शक्ष्यामि चैनं नित्यपर्यायवाचिनं वर्णयितुमिति ।

अतः सिद्धशब्द एवोपात्तो न नित्यशब्दः ॥

(प्रदीपः) नावश्यमिति । तत्राभीक्ष्ण्येन ये शब्दाः प्रयुज्यन्ते आगोपालाङ्गनं तेषामेवान्वाख्यानं स्यात्, न विरलप्रयोगाणाम् । विनाऽपि च क्रियापदप्रयोगेणाभीक्ष्ण्यवृत्तिर्नित्यशब्दः प्रयुज्यते । यथा-'आश्चर्यमनित्ये' 'नित्यवीप्सयोः' इति ॥

(उद्द्योतः) असंदिग्धो नित्यशब्दः किं न प्रयुक्त इत्युक्तम्, तत्रापि संदेहमाह— भाष्ये-अयं खल्विति ॥ आभीक्ष्ण्येन-बाहुल्येन । 'अभीक्ष्णं' इति पाठेऽप्ययमेवार्थः ॥ प्रयुज्यन्त इति । साक्षात् शब्दे आभीक्ष्ण्यासंभवात्प्रयोगद्वारा तत् ग्राह्यम् । एवञ्च नित्यशब्दोपादानेऽपि सप्रयोजनकोऽव्यन्तरसंभवेन तत्रापि संदेह एवेति भावः ॥ 'नित्ये शब्दार्थसंबन्धे' इत्यस्य शब्दार्थसंबन्धे ज्ञाते सति नित्ये-नित्यप्रयोगविषये शब्दे शास्त्रं प्रवृत्तमित्यर्थः स्यादिति तात्पर्यम् ॥ नन्वाभीक्ष्ण्यवाचिनो नित्यं क्रियापदसाकाङ्क्षतया कथं केवलस्य प्रयोगोऽत आह—विनाऽपि चेति ॥

——

(नित्यतासाधकपक्षनिर्णयाधिकरणम्)

(आक्षेपभाष्यम्)

अथ कं पुनः पदार्थं मत्वा एष विग्रहः क्रियते-सिद्धे-शब्दे-अर्थे-संबन्धे चेति ?

(समाधानभाष्यम्)

आकृतिमित्याह ॥

कुत एतत् ?

आकृतिर्हि नित्या, द्रव्यमनित्यम् ॥

(आक्षेपभाष्यम्)

अथ द्रव्ये पदार्थे कथं विग्रहः कर्तव्यः ?

(समाधानभाष्यम्)

सिद्धे-शब्दे-अर्थसंबन्धे चेति । नित्यो ह्यर्थवतामर्थैरभिसंबन्धः ॥

(प्रदीपः) अर्थसंबन्धे चेति । द्रव्यपक्षे द्रव्यस्यानित्यत्वादर्थग्रहणं संबन्धविशेषणार्थमुपात्तम् । अनित्येऽर्थे कथं संबन्धस्य नित्यता-इति चेत्, योग्यतालक्षणत्वात्संबन्धस्य । तस्याश्च शब्दाश्रयत्वात्-शब्दस्य च नित्यत्वाददोषः ॥

(उद्द्योतः) नन्वेवमर्थग्रहणं व्यर्थमत आह—द्रव्यपक्ष इति ॥ योग्यता=बोधजनकत्वयोग्यता-तादात्म्यम् । तदुक्तं भाष्ये-नित्यो ह्यर्थवतामिति । शब्दानामित्यर्थः ॥ ननु तादात्म्यस्य संबन्धत्वे कथं तस्य नित्यत्वमिति चेन्न । नष्टभाविवस्तुनोऽपि शब्देन बोधाद्बौद्धार्थेन तस्य तादात्म्यं नित्यमित्याशयात् । शब्दवृत्तिधर्मस्यैवार्थवृत्तिधर्माभेदमापन्नस्य तादात्म्यत्वेनादोषाच्च ॥ शब्दस्य च नित्यत्वादिति । आकाशवत्तन्निष्ठः शब्दोऽपि नित्यः । व्यञ्जकाभावात्तु न सर्वदोपलम्भ इति भावः ॥

(द्रव्यपदार्थाभ्युपगमभाष्यम्)

अथवा द्रव्य एव पदार्थे एष विग्रहो न्याय्यः—सिद्धे-शब्दे-अर्थे-संबन्धे चेति । द्रव्यं हि नित्यम्, आकृतिरनित्या ॥

कथं ज्ञायते ?

एवं हि दृश्यते लोके-मृत्कयाचिदाकृत्या युक्ता पिण्डो भवति, पिण्डाकृतिमुपमृद्य घटिकाः क्रियन्ते, घटिकाकृतिमुपमृद्य कुण्डिकाः क्रियन्ते ।

तथा—सुवर्णं कयाचिदाकृत्या युक्तं पिण्डो भवति, पिण्डाकृतिमुपमृद्य रुचकाः क्रियन्ते, रुचकाकृतिमुपमृद्य कटकाः क्रियन्ते, कटकाकृतिमुपमृद्य स्वस्तिकाः क्रियन्ते । पुनरावृत्तः सुवर्णपिण्डः पुनरपरयाऽऽकृत्या युक्तः खदिराङ्गारसवर्णे कुण्डले भवतः । आकृतिरन्या चान्या च भवति, द्रव्यं पुनस्तदेव । आकृत्युपमर्देन द्रव्यमेवावशिष्यते ॥

(प्रदीपः) द्रव्यं हि नित्यमिति । असत्योपाध्यवच्छिन्नं ब्रह्मतत्त्वं द्रव्यशब्दवाच्यमित्यर्थः ॥ आकृतिरिति । संस्थानम् । ब्रह्मदर्शने च गोत्वादिजातेरप्यसत्यत्वादनित्यत्वम्, 'आत्मैवेदं सर्वम्' इति श्रुतिवचनात् ॥

(उद्द्योतः) ननु घटादिद्रव्यस्य कथं नित्यतेत्यत आह—असत्येति । स च कम्बुग्रीवादिमदाकारादिरूपः, तद्व्यङ्ग्यजातिरूपश्च ॥ भाष्ये यथाकृतिशब्देन तद्व्यङ्ग्यमुच्यते तर्हि तदप्याविद्यकत्वेन व्यञ्जकानित्यत्वेन चानित्यमित्याह—जातेरपीति । अनेनैतत्प्रकरणस्थाकृतिपदस्य व्यङ्ग्यव्यञ्जकोभयपरता सूचयति । गौतमेनाप्युक्तं "जात्याकृतिव्यक्तयः पदार्थः" इति ॥ भाष्ये 'खदिराङ्गारसवर्णे कुण्डले भवतः' इति प्रयोगादच्यन्ते विकृतेः कर्तृत्वं बोध्यम् ॥

(आकृतिपदार्थाभ्युपगमभाष्यम्)

आकृतावपि पदार्थ एष विग्रहो न्याय्यः—सिद्धे शब्दे अर्थे संबन्धे चेति ॥

ननु चोक्तम्-आकृतिरनित्या-इति ॥

नैतदस्ति । नित्याऽऽकृतिः ॥

कथम् ?

न क्वचिदुपरतेति कृत्वा सर्वत्रोपरता भवति । द्रव्यान्तरस्था तूपलभ्यते ॥

(प्रदीपः) न क्वचिदुपरतेति । अनभिव्यक्तेत्यर्थः । अद्वैतेन लोके व्यवहाराभावात्-व्यवहारे चाकृतेरेकाकारपरामर्शहेतुत्वान्नित्यत्वम् ॥

(उद्द्योतः) आकृतिपदेन जातिरित्यभिप्रायेण-भाष्ये-आकृतावपि पदार्थ इति ॥ क्वचिदुपरतेति कृत्वा न सर्वत्रोपरतेत्यन्वयः ॥ ननूपरमो नाशश्चेत्तत्काले एवान्यत्र सत्त्वं विरुद्धमत आह—

अनभीति ॥ ननु परमार्थदृष्ट्या सर्वमनित्यमत आह—अद्वैतेनेति ॥ नित्यत्वमिति । सर्वदा एकाकारपरामर्शदर्शनेन यावद्व्यवहारकालं तस्या अपि ध्रुवादित्वेन नित्यत्वमिति भावः ॥

(समाधानसाधकनित्यलक्षणभाष्यम्)

अथवा नेदमेव नित्यलक्षणम्-ध्रुवं कूटस्थमविचाल्यनपायोपजनविकार्यनुत्पत्त्यवृद्ध्यव्यययोगि यत् तन्नित्यमिति ।

तदपि नित्यं-यस्मिंस्तत्त्वं न विहन्यते ॥

किं पुनस्तत्त्वम् ?

तद्भावस्तत्त्वम् ॥

आकृतावपि तत्त्वं न विहन्यते ॥

(प्रदीपः) **अथवेति** । असत्यत्वेऽपि तत्त्वतो लोकव्यवहाराश्रयेण जातेर्नित्यत्वं साध्यते । त्रिविधा चानित्यता, **संसर्गानित्यता** यथा—स्फटिकस्य लाक्षाद्युपधाने स्वरूपतिरोधानेन पररूपप्रतिभासः । उपधानापगमे स्वरूपप्रतिभासात्तु परिणामाभावः ॥ **परिणामानित्यता** यथा—बदरफलस्य श्यामतातिरोभावे लौहित्यस्याविर्भावः ॥ **प्रध्वंसानित्यता**—सर्वात्मना विनाशः । एतत्रिविधानित्यताप्रतिक्षेपेण नित्यतां प्रतिपादयितुमुक्तं-**ध्रुवमित्यादि** । तत्र **ध्रुवं कूटस्थमि**ति संसर्गानित्यता परिहृता, **अविचाली**ति परिणामानित्यता, **अनपाये**त्यादिना प्रध्वंसानित्यता ॥

(**उद्योतः**) अथावयवसंस्थानरूपाया जातिव्यञ्जिकाया आकृतेर्यावद्व्यवहारकालं मध्ये मध्ये उत्पत्तौ नाशेऽपि प्रकारान्तरेण नित्यत्वमाह—भाष्ये-**अथवेति** ॥ नित्यत्वलक्षणे ध्रुवपदस्यैव व्याख्यानं-**कूटस्थमिति** । रूपान्तरापत्तिः-**विचालः** । यथा पयसो दध्यादिरूपता । अनेन परिणामानित्यता परास्ता । उत्पत्तेः सत्तापर्यन्तत्वादनुत्पत्तीत्यनेन जन्मसत्तारूपौ भावविकारौ निरस्तौ । **अवृद्धी**त्यनेन तृतीयो वृद्धिलक्षणः । **अनुपजने**ति चतुर्थः परिणामः । **अनपाये**ति पञ्चमोऽपचयः । एतद्रूपविकाररहितमिति तदर्थः ॥ **अव्यये**ति षष्ठो विनाशः । इदं च ब्रह्मविषयं नित्यत्वं, यावद्व्यवहारमेकरूपस्थितपदार्थविषयं च ॥ अयमेव न नित्यशब्दार्थः, प्रवाहाविच्छेदेऽतादृश्यपि नित्यत्वव्यवहारादित्याह—भाष्ये—**तदपी**ति ॥ **यस्मिंस्तत्त्वमिति** । यस्मिन्विहतेऽपि तद्वृत्तिधर्मो न विहन्यते तदित्यर्थः ॥ प्रवाहनित्यता चानेनोक्ता । तन्नाशेऽपि तद्धर्मो न नश्यति । आश्रयप्रवाहाविच्छेदादिति भावः ॥

(नित्यानित्यत्वविचारस्याप्रकृतत्वबोधकभाष्यम्)

अथवा किं न एतेन-इदं नित्यम्-इदमनित्यमिति । यन्नित्यं तं पदार्थं मत्वैष विग्रहः क्रियते—सिद्धे शब्देऽर्थे संबन्धे चेति ॥

(प्रदीपः) **यन्नित्यमिति** । बुद्धिप्रतिभासः शब्दार्थः, यदा यदा शब्द उच्चारितस्तदाऽर्थाकारा बुद्धिरुपजायते-इति प्रवाहनित्यत्वादर्थस्य नित्यत्वमित्यर्थः ॥

(**उद्योतः**) **यन्नित्यमिति** । व्यक्तिजात्याकृतीनां मध्ये यन्नित्यमित्यर्थः ॥ ननु शशशृङ्गादिपदार्थानां कथं नित्यत्वं, तेषां स्वरूपस्यैवाभावादत आह—**बुद्धिप्रतिभास इति** । बाह्यः पदार्थो न शाब्दबोधे विषयः, किंतु बौद्धः । स च प्रवाहनित्य इति भावः ॥ एतच्च मञ्जूषायां विस्तरेण निरूपितम् ॥

(वार्तिकद्वितीयखण्डावतरणभाष्यम्)

कथं पुनर्ज्ञायते-सिद्धः शब्दोऽर्थः संबन्धश्चेति ?

(१ शब्दार्थसंबन्धानां प्रमाणबोधकवार्तिकद्वितीयखण्डम् ॥ २ ॥)

॥ * ॥ लोकतः ॥ * ॥

(भाष्यम्)

यल्लोकेऽर्थमर्थमुपादाय शब्दान्प्रयुञ्जते, नैषां निर्वृत्तौ यत्नं कुर्वन्ति । ये पुनः कार्या भावा निर्वृत्तौ तावत्तेषां यत्नः क्रियते । तद्यथा-घटेन कार्यं करिष्यन् कुम्भकारकुलं गत्वाऽऽह—कुरु घटं कार्यमनेन करिष्यामीति । न तद्वच्छब्दान्प्रयुयुक्षमाणो वैयाकरणकुलं गत्वाऽऽह—कुरु शब्दान्प्रयोक्ष्य इति ।

तावत्येवार्थमुपादाय शब्दान्प्रयुञ्जते ॥

(प्रदीपः) **लोकत इति** । अन्यथा कार्येषु वस्तुषु लोकव्यवहारः, अन्यथा नित्येषु । शाब्दश्च व्यवहारोऽनादिवृद्धव्यवहारपरम्पराव्युत्पत्तिपूर्वक इति शब्दादीनां नित्यत्वम् । घटादयस्त्वर्थक्रियार्थिभिरन्यत आनीयन्ते, उत्पादविनाशयुक्ताश्चोपलभ्यन्ते । नैवं शब्दादयः ॥ **तावत्येवार्थमिति** । बुद्ध्या वस्तु निरूप्येत्यर्थः ॥

(**उद्योतः**) **शब्दादीनां नित्यत्वमिति** । व्याकरणानिष्पाद्यत्वमित्यर्थः ॥ **तावत्येवेति** । वैयाकरणकुलमगत्वैवेत्यर्थः ॥

(इति नित्यतासाधकपक्षनिर्णयाधिकरणम्)

(धर्मनियमाधिकरणम्)

(वार्तिकतृतीयखण्डावतरणभाष्यम्)

यदि तर्हि लोक एषु प्रमाणम्, किं शास्त्रेण क्रियते ?

(१ शास्त्रोपयोगप्रकथने वार्तिकतृतीयखण्डम् ॥ १ ॥)

॥ * ॥ लोकतोऽर्थप्रयुक्ते शब्दप्रयोगे शास्त्रेण धर्मनियमः ॥ * ॥

(भाष्यम्)

लोकतोऽर्थप्रयुक्ते शब्दप्रयोगे शास्त्रेण धर्मनियमः क्रियते ॥

किमिदं धर्मनियम इति ?

धर्माय नियमः-धर्मनियमः, धर्मार्थो वा नियमः-धर्मनियमः, धर्मप्रयोजनो वा नियमः-धर्मनियमः ॥

(प्रदीपः) अत्र भाष्यकारेण संभवन्तीमप्येकवाक्यतामनाश्रित्य वाक्यत्रयं स्थापितम् । **सिद्धे शब्दार्थसंबन्धे**श्चा प्रवृत्तमित्येकं वाक्यम् । कथं ज्ञायत इति प्रश्ने **लोकतो** ज्ञायते इति द्वितीयम् । लोकत इत्यस्यावृत्त्या **लोकतोऽर्थ**-

प्रयुक्त इत्यादि तृतीयेयम् ॥ **शब्दप्रयोग इति** । प्रयोगग्रहणेन प्रयोगाद्धर्मो न तु ज्ञानमात्रात्' इत्युक्तं भवति । अर्थेनात्मप्रत्यायनाय प्रयुक्तः—अर्थप्रयुक्तः ॥

धर्माय नियम इति । चतुर्थ्या तादर्थ्यं प्रतिपाद्यते। संबन्धसामान्ये तु षष्ठीं विधाय समासः कर्तव्यः, चतुर्थीसमासस्य प्रकृतिविकारभाव एव विधानात् ॥ **धर्मार्थ इति** । धर्मार्थत्वान्नियम एव धर्मशब्देनाभिधीयते—इति कर्मधारयः समासः ॥ **धर्मप्रयोजन इति** । लिङादिविषयेण नियोगाख्येन धर्मेण प्रयुक्त इत्यर्थः ॥

(**उद्द्योतः**) ननु सकृदन्वितस्य **'लोकतः'** इत्यस्य पुनः **'अर्थप्रयुक्ते'** इत्यनेनान्वयः कथम्? वार्तिके चैकवाक्यतयैवान्वयः प्रतीयतेऽत आह—**अत्रेति** ॥ **अनाश्रित्येति** । न्यूनतापरिहारायेत्यर्थः । **'लोकतः'** इत्यस्य च लोकव्यवहारत इत्यर्थः ॥ भाष्ये—**अर्थप्रयुक्ते इति** । अर्थज्ञानप्रयोजनेन कृत इत्यर्थः । परस्य विशिष्टार्थबोधो भवत्विति शब्दः प्रयुज्यते, प्रयोगेणाविर्भूतशब्दज्ञानेनार्थज्ञानादिति भावः ॥ एवमप्रासशब्दप्रयोगे शास्त्रेणास्येयं प्रकृतिरयं प्रत्यय इत्यादिप्रकृत्यादिविभागज्ञानद्वारा गवादय एव प्रयुक्ता धर्मजनकाः, न गाव्यादय इति नियमः क्रियत इति तात्पर्यम् ॥ **विधानादिति** । तादर्थ्यस्य षष्ठ्यर्थत्वबोधनाय त्वेवं प्रयोग इति भावः ॥ **'चतुर्थी'** इति योगविभागो न भाष्यारूढः, **'सुप्सुपा'** इति समास इत्यप्यगतिकगतिरित्येवं व्याख्यातम् ॥ द्वितीयपक्षात्तृतीये विशेषं दर्शयति—**लिङादिति** । प्रभाकराङ्गीकृतमतेनेदम् । तन्मते हि लिङादीनामपूर्वरूपं कार्यं वाच्यम् । तदेव च स्वस्मिन् पुरुषं प्रयुञ्जानं **नियोग** इत्युच्यते । स एव धर्मः, तेन प्रयुज्यते—आक्षिप्यते इति कर्मल्युडन्तः प्रयोजनशब्दः । स चासाधुनिवृत्तिरूपो नियमः । **'धर्मप्रयोजनः'** इति षष्ठीसमासः । एवं च द्वितीये धर्मफलको नियम इत्यर्थः । तृतीये धर्मप्रयोज्य इत्यर्थ इति भेदः ॥ केचित्तु **'धर्माय नियमः'** इत्यनेन प्रत्यवायपरिहाररूपधर्मायायं नियमः, असाधुप्रयोगेऽधर्मोत्पत्तेः ॥ **'धर्मार्थो नियमः'** इत्यनेन धर्मस्य यज्ञादेरङ्गभूत इत्यर्थः, **'नानृतं वदेत्'** इति क्रत्वङ्गवाक्येन क्रतुवैगुण्यस्य बोधनात् ॥ **'धर्मप्रयोजनो नियमः'** इत्यनेन **'एकः शब्दः'** इति श्रुतेर्नियमादृष्टं पुरुषार्थकरं सूचितमित्याहुः ॥

(१ वार्तिकचतुर्थखण्डम् ॥ २ ॥)

॥ * ॥ यथा लौकिकवैदिकेषु ॥ * ॥

(भाष्यम्)

प्रियतद्धिता दाक्षिणात्याः । 'यथा लोके वेदे च' इति प्रयोक्तव्ये 'यथा लौकिकवैदिकेषु' इति प्रयुञ्जते ॥

अथवा—युक्त एव तद्धितार्थः । यथा लौकिकवैदिकेषु च कृतान्तेषु ॥

लोके तावत्—'अभक्ष्यो ग्राम्यकुक्कुटः, अभक्ष्यो ग्राम्यसूकरः' इत्युच्यते । भक्ष्यं च नाम क्षुत्प्रतीघातार्थमुपादीयते । शक्यं चानेन श्वमांसादिभिरपि क्षुत्प्रतिहन्तुम् । तत्र नियमः क्रियते—इदं भक्ष्यम्, इदमभक्ष्यमिति ॥ तथा—खेदात्स्त्रीषु प्रवृत्तिर्भवति। समानश्च खेदविगमो गम्यायां चागम्यायां च। तत्र नियमः क्रियते-इयं गम्या-इयमगम्येति ॥

(**प्रदीपः**) **प्रियतद्धिता इति** । नायमपशब्दः, किंतु ये लोकवेदयोर्भवा अवयवास्ते लोकवेदशब्दाभ्यामभिधातुं शक्यन्ते । आधाराधेयभावकल्पनया तु तद्धितप्रयोगः प्रियतद्धितत्वनिमित्तः । यथा-कश्चिद्वनस्पतय इति प्रयुङ्क्ते, कश्चिद्वानस्पत्यमिति समूहप्रत्ययान्तम् ॥

अथवेति । नात्रावयवावयविविभागः, किं तर्हि? **वेदलोकव्यतिरिक्तः** सिद्धान्तः शब्दार्थो भवरूप इत्यर्थः ॥ **लौकिकः—**स्मृत्युपनिबद्धः । **वैदिकः**-श्रुत्युपनिबद्धः । **शक्यं चानेनेति** । शकेः कर्मसामान्ये लिङ्गसर्वनामनपुंसकयुक्ते कृत्यप्रत्ययः । ततः शब्दान्तरसंबन्धादुपजायमानमपि स्त्रीत्वं बहिरङ्गत्वादन्तरङ्गसंस्कारं न बाधते इति **'शक्यं···क्षुत्'** इत्युक्तम् । यदा तु पूर्वमेव विशेषविवक्षा तदा 'शक्या क्षुत्' इति भवत्येव । यदा तु प्रतिघातस्यैव क्षुत्कर्म, शकेस्तु प्रतिघातः, तदा 'क्षुधं प्रतिहन्तुं शक्यम्' इति भवति ॥ **खेदादिति** । खेदयतीति–खेदः=रागः, इन्द्रियनियमासामर्थ्यं वा खेदः ॥

(**उद्द्योतः**) नन्वीदृशो धर्मनियमः क दृष्टोऽत आह भाष्ये—**यथेति** ॥ ननु 'लोकवेदयोः' इत्येव सिद्धे तद्धितनिर्देशोऽयुक्तोऽत आह—**प्रियतद्धिता इति** ॥ नन्वन्यार्थेऽन्यशब्दप्रयोगेऽपशब्दत्वं स्यादत आह—**नायमिति** ॥ **ते वेदलोकेति** । अवयवे समुदायशब्दप्रयोगदर्शनादिति भावः ॥ **आधाराधेयकल्पनया त्विति** । लोकरूपसमुदायतदवयवयोरित्यादिः ॥ **नात्रावयवावयविविभाग इति** । 'तत्र भवः' इत्यादिव्यवहारप्रयोजको विभागात्पोऽवयवावयविनोर्नेत्यर्थः ॥ **कृतान्तेषु** । कृतान्तः—सिद्धान्तः, तत्प्रतिपादकवाक्येष्वित्यर्थः ॥ **'भक्ष्यं च नाम'** इत्यस्य तद्भवति यदिति शेषः ॥ 'शक्यं क्षुध्' इति सामानाधिकरण्यं कथं भिन्नलिङ्गत्वादत आह—**शकेरिति** ॥ **तदा क्षुधमिति** । ननु प्रधानक्रियानिरूपितशक्तेरभिधाने गुणक्रियानिरूपितशक्तेरनभिहितायाः अभिहितवत्प्रकाशस्य **'स्वादुमि णमुल्'** इत्यत्र वक्ष्यमाणत्वेन कथमेतत्? इति चेत्, न । प्रधानतिङन्तार्थक्रियानिरूपितशक्तेरेवायं स्वभावो यत् स्वसमानाधिकरणगुणशक्तेरभिहितवत्प्रकाश **इत्यभिमानः** । वस्तुत इदमयुक्तमेवेति **'स्वादुमि-'** इत्यत्र विरूपयिष्यामः ॥ **खेद इति** । एवञ्च ग्राम्यकुक्कुटपरदारादौ विशेषनिषेधस्येतराभ्यनुज्ञाफलकतया आरण्यकतद्भक्षणस्वदारगमनयोर्यथा दोषाभावः, यथा च ग्राम्यकुक्कुटभक्षणपरदारगमनयोरधर्मः, तथा शास्त्रजनितज्ञानपूर्वके गवादिप्रयोगेऽपूर्वोत्पत्तिरूपं फलं शास्त्रेण बोध्यते; तेषां साधुत्वबोधनात् । अर्थादपशब्दानामधर्मजनकत्वं बोध्यते, एकविधेस्तदितरनिषेधफलकत्वात् । यथैकनिषेधस्यापराभ्यनुज्ञाफलकत्वमिति भावः । दृष्टान्तता त्वंशेन, वक्ष्यमाणवैदिकानां तु सर्वांशेनेति बोध्यम् ॥

(वैदिकसिद्धान्तोपपादकभाष्यम्)

वेदे खल्वपि—"पयोव्रतो ब्राह्मणः-यवागूव्रतो राजन्यः-आमिक्षाव्रतो वैश्यः" इत्युच्यते । व्रतं च नामाभ्यवहारार्थमुपादीयते । शक्यं चानेन शालिमांसादीन्यपि व्रतयितुम् । तत्र नियमः क्रियते ।

तथा-"बैल्वः खादिरो वा यूपः स्यात्" इत्युच्यते । यूपश्च नाम पश्वनुबन्धार्थमुपादीयते । शक्यं चानेन यत्किंचिदेव काष्ठमुच्छ्रित्यानुच्छ्रित्य वा पशुरनुबन्धुम् । तत्र नियमः क्रियते ।

तथा-"अग्नौ कपालान्यधिश्रित्याभिमन्त्रयते—भृगूणामङ्गिरसां घर्मस्य तपसा तप्यध्वम्" इति । अन्तरेणापि मन्त्रमग्निर्दहनकर्मा कपालानि सन्तापयति । तत्र च नियमः क्रियते ।

एवं क्रियमाणमभ्युदयकारि भवतीति ॥

(प्रदीपः) **पयोव्रत इति** । सत्यामर्थितायां 'पय एव व्रतयति' इति नियमोऽयं न तु विधिः, अर्थित्वाभावे कारणाभावात् ॥

(उद्योतः) **व्रतयतीति** । अभ्यवहार्यत्वेनोपादत्ते-इत्यर्थः ॥ भाष्ये-उच्छ्रित्यानुच्छ्रित्य वेति । संतक्ष्यासंतक्ष्य वेत्यर्थः । निखन्यानिखन्य वेत्यर्थ इत्यन्ये ॥

(दार्ष्टान्तिक उपसंहारभाष्यम्)

एवमिहापि समानायामर्थगतौ शब्देनापशब्देन च धर्मनियमः क्रियते—शब्देनैवार्थोऽभिधेयो नापशब्देनेति । एवं क्रियमाणमभ्युदयकारि भवतीति ॥

(प्रदीपः) **समानायामिति** । यद्यपि साक्षादपभ्रंशा न वाचकास्तथापि स्मर्यमाणसाधुशब्दव्यवधानेनार्थं प्रत्याययन्ति । केचिच्चापभ्रंशाः परम्परया निरूढिमागताः साधुशब्दानस्मारयन्त एवार्थं प्रत्याययन्ति ॥ **अन्ये** तु मन्यन्ते—साधुशब्दवदपभ्रंशा अपि साक्षादर्थस्य वाचका इति ॥

(उद्योतः) ननु अपभ्रंशा न वाचकाः, वाच्यप्रतीत्यन्यथाऽनुपपत्त्या कल्प्यमानशक्तेः शिष्टप्रयुक्तसंस्कृतेष्वेव कल्पनात् । तदनुसारेणैव चापभ्रंशानां साधुस्मरणेन बोधकत्वोपपत्तेः **'समानायां'** इत्यनुपपन्नमिति शङ्कते—**यद्यपीति** ॥ **तथापीति** । एवं च वाचकत्वाभावेऽप्यर्थप्रत्यायकत्वाविशेषेण **'समानायां'** इत्युक्तम् ॥ **निरूढिमागता इति** । ते च शक्तिभ्रमेण बोधका इति भावः ॥ शक्तिभ्रमश्चेत्थम्—केनचित् 'गावी' इति प्रयुक्ते 'गौः' इति साधुस्मरणात् प्रयोज्यस्य बोधेऽपि तटस्थस्य गावीशब्दादेवास्य गोबोध इति भ्रमेण तन्मूलकोऽन्येषामपि भ्रम इति ॥ वस्तुतो विनिगमनाविरहात् भाषाशब्देष्वपि शक्तिरेवेत्याह—**अन्ये त्विति** । **साधुत्वं चैत**न्मते शब्दगतधर्मसाधनतावच्छेदकवैजात्यमेव । यद्यपि **'साधूनेव भाषेत'** इति न श्रूयते, तथापि फलनिर्देशवाक्ये तन्निर्देशादेवेदृशविधिः कल्प्यते । तत्र 'के साधवः' इत्याकाङ्क्षायामेत एव साधव इति व्याकरणेन निष्पादनात्तद्द्वारा शास्त्रेण धर्मनियमो विधीयत इति बोध्यम् ॥ भाष्ये—**शब्देनैवेति** । साधुनेत्यर्थः ॥ **एवं क्रियमाणमिति** । शास्त्रज्ञानपूर्वकमुच्चार्यमाणमित्यर्थः ॥

इति धर्मनियमाधिकरणम् ॥

(शब्दविषयप्रदर्शनाधिकरणम्)

(नियमाक्षेपे वार्तिकांशानुवादभाष्यम् ॥)

॥ अस्त्यप्रयुक्तः ॥

सन्ति वै शब्दा अप्रयुक्ताः । तद्यथा—ऊष, तेर, चक्र, पेच-इति ॥

किमतो यत्सन्त्यप्रयुक्ताः ?

प्रयोगाद्धि भवाञ्छब्दानां साधुत्वमध्यवस्यति । य इदानीमप्रयुक्ताः, नामी साधवः स्युः ॥

(प्रदीपः) **अस्त्यप्रयुक्त इति** । प्रयोगमूलत्वादस्याः स्मृतेरप्रयुक्तानामप्यन्वाख्यानादप्रामाण्यमाशङ्कते ॥

(उद्योतः) **'अस्त्यप्रयुक्तः'** इत्यादेः प्रकृतोपयोगमाह—**प्रयोगमूलत्वादिति** । *लोकतोऽर्थप्रयुक्ते शब्दप्रयोगे शास्त्रेण धर्मनियमः* इत्यनेन प्रयुक्तेषु साध्वसाधुषु प्रयुक्तसाध्वन्वाख्यानेन तेषु धर्मः प्रयुक्तासाधुष्वधर्म इत्यर्थकेनेदं सूचितम् । एवंचाप्रयुक्तानामप्रयोगेणैवासाधुत्वानुमानादसाधूनामप्यनेनान्वाख्यानादप्रामाण्यमिति भावः ॥ वार्तिकोक्तनियमानुपपत्तिश्चेत्यपि बोध्यम् ॥

भाष्ये-**किमत इति**। अप्रयुक्तसत्त्वं नास्माकमनिष्टं, साधुमात्रार्थत्वाद्व्याकरणस्येत्यर्थः ॥

उत्तरम्—**प्रयोगादिति** । तथा चाप्रयोगादसाधुत्वानुमानमिति भावः ॥

(आक्षेपासंगतिबोधकभाष्यम्)

इदं तावद्विप्रतिषिद्धम्—यदुच्यते—'सन्ति वै शब्दाः, अप्रयुक्ताः' इति ।

यदि सन्ति, नाप्रयुक्ताः ।

अथाप्रयुक्ताः, न सन्ति । सन्ति चाप्रयुक्ताश्चेति विप्रतिषिद्धम् । प्रयुञ्जान एव खलु भवानाह—सन्ति शब्दा अप्रयुक्ता इति । कश्चेदानीमन्यो भवज्जातीयकः पुरुषः शब्दानां प्रयोगे साधुः स्यात् ?

(प्रदीपः) यथा घटादीनां विनाऽप्यर्थक्रियया सत्त्वं गम्यते नैवं शब्दानां, ते हि सर्वदा व्यवहाराय प्रयुज्यमानाः सन्तः सत्त्वेनावसीयन्ते-इत्याह—**इदमिति** । **कश्चेदानी**मिति उपहासपरम् ॥

(उद्योतः) विप्रतिषिद्धत्वमुपपादयति—**यथेति** । एवं च सत्त्वे प्रयोग आवश्यक एव, अप्रयोगे च सत्त्वमेव न स्यादिति भावः ॥ ननु लक्षणवशेन सत्त्वं, केनाप्यप्रयोगाच्चाप्रयुक्तत्वमिति न विरोधोऽतो भाष्ये—**प्रयुञ्जान एवेति** ॥ ननु मया प्रयुक्तश्चेत्किम् ? तत्र सोपहासमाह—**कश्चेदानीमिति** । स्वयमेव प्रयोगं कृत्वा **'सन्ति चाप्रयुक्ताः'** इत्यादीनां शब्दानां प्रयोगे साधुर्योग्यः स्यादित्यर्थः । त्वत्प्रयोगेणैव प्रयुक्तत्वावगमेऽप्रयुक्तत्वोक्तिर्विरुद्धेति भावः ॥

(आक्षेपसंगतिसाधकभाष्यम्)

नैतद्विप्रतिषिद्धम् । सन्तीति तावद्ब्रूमः, यदेताञ्छास्त्रविदः शास्त्रेणानुविदधते ॥

अप्रयुक्ता इति ब्रूमः, यल्लोकेऽप्रयुक्ता इति ॥

यदप्युच्यते—'कश्चेदानीमन्यो भवज्जातीयकः पुरुषः शब्दानां प्रयोगे साधुः स्यात्' इति ।

न ब्रूमोऽस्माभिरप्रयुक्ता इति ।

किं तर्हि ?

लोकेऽप्रयुक्ता इति ॥

(प्रदीपः) उत्तरं तु शास्त्रदृष्ट्या प्रकृतिप्रत्ययादिसद्भावादनुमितसत्त्वाः, व्यवहारे तु न दृश्यन्त इत्युक्तम् ॥

(आक्षेपभाष्यम्)

ननु च भवानप्यभ्यन्तरो लोके ॥

(समाधानभाष्यम्)

अभ्यन्तरोऽहं लोके, न त्वहं लोकः ॥

(प्रदीपः) न त्वहं लोक इति । यथा लोकोऽर्थावगमाय शब्दान् प्रयुङ्क्ते नैवं मयैतेऽर्थे प्रयुक्ताः, अपि तु स्वरूपपदार्थका इत्यर्थः ॥

(उद्द्योतः) ननु लोकान्तर्भूतस्य 'न त्वहं लोकः' इति वचो विरुद्धमत आह—यथेति । अर्थबोधाय शब्दान्प्रयुञ्जानो हि मम लोकत्वेनाभिमत इत्यर्थः ॥

(२ नियमाक्षेपबाधकं वार्तिकम् ॥ १ ॥)

॥ * ॥ अस्त्यप्रयुक्त इति चेत् नार्थे शब्दप्रयोगात् ॥ * ॥

(भाष्यम्) अस्त्यप्रयुक्त इति चेत्, तन्न ।

किं कारणम् ?

'अर्थे शब्दप्रयोगात्' अर्थे शब्दाः प्रयुज्यन्ते । सन्ति चैषां शब्दानामर्था येष्वर्थेषु प्रयुज्यन्ते ॥

(प्रदीपः) अर्थे शब्दप्रयोगादिति । अर्थसद्भावः शब्दसद्भावे लिङ्गम् । न हि विना शब्देनार्थप्रत्यायनमुपपद्यते ॥

(उद्द्योतः) भाष्ये-अर्थे शब्दप्रयोगादिति । अर्थविषयकज्ञानाय शब्दप्रयोगादित्यर्थः ॥ तदाशयमाह—अर्थसद्भाव इति ॥

(३ बाधकांशनिरासवार्तिकम् ॥ २ ॥)

॥ * ॥ अप्रयोगः प्रयोगान्यत्वात् ॥ * ॥

(भाष्यम्)

अप्रयोगः खल्वप्येषां शब्दानां न्याय्यः ।

कुतः ?

'प्रयोगान्यत्वात्' । यदेतेषां शब्दानामर्थेऽन्याञ्छब्दान्प्रयुञ्जते । तद्यथा—'ऊष' इत्यस्य शब्दस्यार्थे—क्व यूयमुषिताः, 'तेर' इत्यस्यार्थे-क्व यूयं तीर्णाः, 'चक्र' इत्यस्यार्थे—क्व यूयं कृतवन्तः । 'पेच' इत्यस्यार्थे—क्व यूयं पक्ववन्त इति ॥

(प्रदीपः) इतरोऽन्यथासिद्धतामाह—अप्रयोग इति । यतोऽन्ये तेषामर्थानां सन्ति वाचकास्ततो नैषामनुमानमुपपद्यते । यद्यपि 'ऊष' इत्यस्य 'उषिताः' इति समानार्थौ न भवति, परोक्षतादेर्विशेषस्यानवगमात्, तथापि तत्प्रत्यायनाय पदान्तरसहितः प्रयुज्यते ॥

(उद्द्योतः) भाष्ये—प्रयोगान्यत्वादिति । प्रयुज्यत इति-प्रयोगः=शब्दः, सोऽन्यो यस्यार्थस्यास्ति तत्त्वादित्यर्थः । सर्वनाम्नः परनिपातः, पूर्वनिपातप्रकरणानित्यत्वात् ॥ पदान्तरसहित इति । पदान्तरं-क्व यूयमिति । तत्र 'क्व' इत्यनेन साधनपारोक्ष्यं, निष्ठया भूतत्वं कर्तृत्वं च, 'यूयं' इत्यनेन मध्यमपुरुषबोध्यमाभिमुख्यं बहुत्वञ्च, चेतनत्वं वा बहुत्वं च । वसेः साक्षात् 'गत्यर्थाकर्मक–' इत्यत्र निर्देशात्, तरतेर्गत्यर्थत्वात् कर्तरि क्तः ॥ नन्वाख्याते क्रियाविशेष्यको बोधः, अत्र कर्तृविशेष्यकः–इति कथं लिडन्तसमानार्थत्वम् ? इति चेत्, न । विषयताविशेषानादरेण तथोक्तेः । न चाख्याते क्रियाविशेष्यकबोधे 'पक्ष्यति भवति' 'अपाक्षीद्भवति' इति भूवादिसूत्रस्थभाष्यप्रयोगविरोधः, अतीतानागतपाककर्तृकसत्ताया वर्तमानत्वासङ्गतेरिति वाच्यम् । वर्तमानसामीप्ये तत्र लटः सत्त्वात् । 'तरति ब्रह्महत्यां योऽश्वमेधेन यजते' इत्यादौ यत्कर्तृको य..स्तत्कर्तृकं तरणमिति बोधः । अत एव 'ह्रस्वो नपुंसके–' इति सूत्रे 'रमते ब्राह्मणकुलमिति क्रियाप्रधानं' इति भाष्ये उक्तम् ।

(४ बाधकोपपत्तिवार्तिकम् ॥ ३ ॥)

॥ * ॥ अप्रयुक्ते दीर्घसत्रवत् ॥ * ॥

(भाष्यम्)

यद्यप्यप्रयुक्ताः, अवश्यं दीर्घसत्रवल्लक्षणेनानुविधेयाः । तद्यथा-दीर्घसत्राणि वार्षशतिकानि वार्षसहस्रिकाणि च, न चाद्यत्वे कश्चिदप्याहरति । केवलमृषिसंप्रदायो धर्म इति कृत्वा याज्ञिकाः शास्त्रेणानुविदधते ॥

(प्रदीपः) संप्रत्यप्रयुज्यमानानामपि पूर्वं प्रयुक्तत्वादनुशासनं कर्तव्यमित्याह—अप्रयुक्त इति ॥ ऋषिसंप्रदाय इति । वेदाध्ययनमित्यर्थः ॥

(उद्द्योतः) नन्वप्रयुक्तानुशासने निर्मूलत्वाच्छास्त्रस्याप्रामाण्यं स्यादत आह—संप्रतीति । पाणिनेर्व्याकरणप्रणयनकाले इ-त्यर्थः । पूर्वप्रयोगसत्ता च व्याकरणप्रणयनादेवानुमीयत इति भावः । इदमपि यत्र भाष्यवार्तिककाराभ्यामप्रयुक्तत्वं नोक्तं तदभिप्रायकमनुमानं बोध्यम् ॥ (भाष्ये) वार्षशतिकानीति । वर्षशब्दो दिवसपरः, यथाश्रुत एव वा ॥ आहरति । सामग्र्यभावादिति भावः ॥ ननु सत्राणां बहुयजमानकानामृषिभिर्वसिष्ठादिभिः संप्रदीयमानत्वाभावादृषिसंप्रदाय इत्ययुक्तमत आह—वेदेति ॥ भाष्ये 'कृत्वा' इत्यनन्तरं 'अधीयते' इति शेषः । याज्ञिकाश्च कल्पसूत्रेणान्वाचक्षत इत्यर्थः । अत्र सत्राणां कर्मत्वम् ॥

॥ * ॥ सर्वे देशान्तरे ॥ * ॥

(भाष्यम्)

सर्वे खल्वप्येते शब्दा देशान्तरेषु प्रयुज्यन्ते ॥

(प्रदीपः) सर्वे इति । इदमत्र तात्पर्यम्—यस्य कस्यचिद्वचनात्प्रयोगाप्रयोगौ न व्यवतिष्ठेते, अपि तु शिष्टानामेव वचनात् ॥

(आक्षेपभाष्यम्)

न चैवोपलभ्यन्ते ॥

(उद्योतः) मनुपलभ्याऽप्रयुक्तत्वं शङ्कते—भाष्ये-न चैवेति ॥

(समाधानभाष्यम्)

उपलब्धौ यत्नः क्रियताम् ॥ महान् शब्दस्य प्रयोगविषयः । सप्तद्वीपा वसुमती, त्रयो लोकाः, चत्वारो वेदाः साङ्गाः सरहस्या बहुधा भिन्नाः—एकशतमध्वर्युशाखाः, सहस्रवर्त्मा सामवेदः, एकविंशतिधा बाह्वृच्यं, नवधाऽऽथर्वणो वेदः, वाकोवाक्यम्, इतिहासः, पुराणं, वैद्यकमित्येतावाञ्छब्दस्य प्रयोगविषयः । एतावन्तं शब्दस्य प्रयोगविषयमननुनिशम्य 'सन्त्यप्रयुक्ताः' इति वचनं केवलं साहसमात्रमेव ॥

(प्रदीपः) वाकोवाक्यशब्देनोक्तिप्रत्युक्तिरूपो ग्रन्थ उच्यते । यथा—"किंस्विदावपनं महत्, भूमिरावपनं महत्" इति । पूर्वचरितसंकीर्तनं—इतिहासः । वंशाद्यनुकीर्तनं—पुराणम् ॥

(उद्योतः) इतरलोकापेक्षया वसुमत्यां शब्दबाहुल्यात्तस्याः पृथग्ग्रहणम् । अनेनान्त्यपातालपर्यन्तसंग्रहः । त्रयो लोकाः—स्वस्तेनोपरितनसकलसंग्रहः । रहस्यम्—उपनिषत् । मन्वादिस्मृतयो वा, वेदनिगूढार्थप्रकाशकत्वात् । एवं च देशान्तरशब्दः शाखान्तरवेदान्तरोपलक्षक इति बोध्यम् ॥

(शब्दानां नियतविषयकत्वदर्शकभाष्यम्)

एतस्मिंश्चातिमहति शब्दस्य प्रयोगविषयेते ते शब्दास्तत्र तत्र नियतविषया दृश्यन्ते । तद्यथा—शवतिर्गतिकर्मा कम्बोजेष्वेव भाषितो भवति, विकार एनमार्या भाषन्ते—शव इति । हम्मतिः सुराष्ट्रेषु, रंहतिः प्राच्यमध्येषु, गमिमेव त्वार्याः प्रयुञ्जते । दातिर्लवनार्थे प्राच्येषु, दात्रमुदीच्येषु ॥

(प्रदीपः) विकार इति । जीवतो मृतावस्था—विकारः, तत्रेत्यर्थः ॥

(उद्योतः) भाष्ये—हम्मतिरित्यत्र रंहतिरित्यत्र च 'गतिकर्मा' इत्यनुकर्षः ॥ दातिर्लवनार्थे इति । क्तिन्नन्तं क्तिजन्तं वा । लवनेऽर्थे दातिशब्दं प्राच्याः प्रयुञ्जते, तत्रार्थे दात्रशब्दमुदीच्या इत्यर्थः ॥

(अप्रयुक्तशब्दोपलम्भकभाष्यम्)

ये चाप्येते भवतोऽप्रयुक्ता अभिमताः शब्दा एतेषामपि प्रयोगो दृश्यते ॥

क्व ?

वेदे । तद्यथा—"यद्वो रेवतीरेवत्यन्तमूष, यन्मे नरः श्रुत्यं ब्रह्म चक्र, यत्रा नश्चक्रा जरसं तनूनाम्" इति ॥

इति शब्दविषयप्रदर्शनाधिकरणम् ॥

(अथ शब्दज्ञानस्य धर्मजनकताधिकरणम्)

(आक्षेपभाष्यम्)

किं पुनः—शब्दस्य ज्ञाने धर्मः, आहोस्वित्प्रयोगे ?

(प्रदीपः) किं पुनरिति । "एकः शब्दः सम्यक् ज्ञातः सुप्रयुक्तः स्वर्गे लोके कामधुग्भवति" (६।१।८४) इति श्रुतिः । तत्र किं सम्यक् ज्ञातः कामधुग्भवति, सुप्रयोगात्तु सम्यग्ज्ञातत्वानुमानमित्यर्थः; आहोस्वित्सुप्रयुक्तः कामधुक् भवति, सुप्रयुक्तत्वं सम्यग्ज्ञानादित्यर्थ इति प्रश्नः ॥

(उद्योतः) वार्तिकोक्तो धर्मनियमः श्रुतिसिद्धस्तस्यासुभयोः श्रवणात्प्रश्न इत्याह—एकः शब्द इति । तत्र 'यदेकस्मादपूर्वं तदितरत्तदर्थम्' इति न्यायात् द्वयोः साम्येन फलसंबन्धाभावाद्विकल्पायोगेनैकस्य प्राधान्यम्, अपरस्याङ्गत्वं कल्प्यम् ॥ तत्र "प्रथमं वा नियम्येत—" (पू० मी० ११।१।४२) इति न्यायाश्रयेणाह—तत्र किमिति ॥

सर्वत्रैव हि विज्ञानं संस्कारत्वेन गम्यते ।

पराङ्गं चात्मविज्ञानादन्यत्रेत्यवधार्यताम् ॥ इति—

न्यायेन ज्ञानस्य शेषशेषतया धर्महेतुत्वाभावात्, प्रयोगाङ्गतया दृष्टार्थत्वाच्च, प्रयोगस्य फलं प्रति संनिहितत्वाच्चाह—आहो स्विदिति ॥

(प्रत्याक्षेपभाष्यम्)

कश्चात्र विशेषः ?

(१ ज्ञानपक्षदूषणवार्तिकम् ॥ १ ॥)

॥ * ॥ ज्ञाने धर्म इति चेत्तथाऽधर्मः ॥ * ॥

(भाष्यम्)

ज्ञाने धर्म इति चेत्तथाऽधर्मः प्राप्नोति । यो हि शब्दान् जानाति, अपशब्दानप्यसौ जानाति । यथैव शब्दज्ञाने धर्मः, एवमपशब्दज्ञानेऽप्यधर्मः ॥

(प्रदीपः) ज्ञाने धर्म इति चेदिति । यथा श्लेष्मणः प्रकोपनं स्नेहद्रव्यं, रूक्षं वायोः, तथेहापि प्राप्तमिति भावः ॥

(उद्योतः) यथा श्लेष्मण इति । तथा धर्मजनकज्ञानविपरीतत्वात् तद्विपरीतजनकत्वेनापशब्दज्ञानादधर्मप्राप्तिरित्यर्थः ॥

(अधर्माधिक्यदर्शनभाष्यम्)

अथवा भूयानधर्मः प्राप्नोति । भूयांसो ह्यपशब्दाः, अल्पीयांसः शब्दाः । एकैकस्य शब्दस्य बहवोऽपभ्रंशाः । तद्यथा—गौरित्यस्य गावी-गोणी-गोता-गोपोतलिकेत्येवमादयोऽपभ्रंशाः ॥

(७ ज्ञानपक्षाभावबोधकं वार्तिकम् ॥ २ ॥)

॥ * ॥ आचारे नियमः ॥ * ॥

(भाष्यम्)

आचारे पुनर्ऋषिर्नियमं वेदयते—"तेऽसुरा हेलयो हेलय इति कुर्वन्तः पराबभूवुः" इति ॥

(प्रदीपः) आचार इति । प्रयोगे ॥ ऋषिः—वेदः ॥

(उद्द्योतः) प्रयोगे इति । एवं च प्रयोगादेवाधर्मवद्धर्मोऽपीति 'ज्ञानाद्धर्मः' इति वेदविरुद्धमिति भावः ॥

इति ज्ञानपक्षनिराकरणम् ॥

(अथ प्रयोगपक्षाङ्गीकारभाष्यम्)

अस्तु तर्हि प्रयोगे ॥

(८ प्रयोगपक्षे दूषणवार्तिकम् ॥ ३ ॥)

॥ * ॥ प्रयोगे सर्वलोकस्य ॥ * ॥

(भाष्यम्)

यदि प्रयोगे धर्मः, सर्वो लोकोऽभ्युदयेन युज्येत ॥

(आक्षेपभाष्यम्)

कश्चेदानीं भवतो मत्सरः, यदि सर्वो लोकोऽभ्युदयेन युज्येत ?

(समाधानभाष्यम्)

न खलु कश्चिन्मत्सरः । प्रयत्नानर्थक्यं तु भवति । फलवता च नाम यत्नेन भवितव्यम् । न च प्रयत्नः फलाद्व्यतिरेच्यः ॥

(प्रदीपः) न च प्रयत्न इति । यदि प्रयत्नेन विना फलं स्यात् प्रयत्नवैयर्थ्यमापद्येतेत्यर्थः ॥

(उद्द्योतः) भाष्ये—फलाद्व्यतिरेच्य इति । फलवद्वृत्त्यभावप्रतियोगी न कार्य इत्यर्थः ॥ प्रयत्नवैयर्थ्यमिति । व्याकरणाध्ययनविषयकप्रयत्नवैयर्थ्यमित्यर्थः ॥

(समाधानबाधकभाष्यम्)

ननु च ये कृतप्रयत्नास्ते साधीयः शब्दान्प्रयोक्ष्यन्ते, अत एव साधीयोऽभ्युदयेन योक्ष्यन्ते ॥

(उद्द्योतः) साधीय इति । क्रियाविशेषणम् । शास्त्रसंस्कारवतां प्रभूतशब्दप्रयोगजन्यबहुपूर्वद्वारा बहुतराभ्युदययुक्तत्वमित्यर्थः ॥

(समाधानसाधकभाष्यम्)

व्यतिरेकोऽपि वै लक्ष्यते । दृश्यन्ते हि कृतप्रयत्नाश्चाप्रवीणाः, अकृतप्रयत्नाश्च प्रवीणाः । तत्र फलव्यतिरेकोऽपि स्यात् ॥

(प्रदीपः) व्यतिरेक इति । परिहासः ॥

(उद्द्योतः) भाष्ये—तत्र फलव्यतिरेक इति । कौशलव्यतिरेकवत् फलव्यतिरेकोऽपि स्यादिति तस्य व्याकरणाध्ययनं व्यर्थमेव स्यादिति भावः ॥

(पक्षद्वयनिराकरणोपसंहारवार्तिकावतरणभाष्यम्)

एवं तर्हि—नापि ज्ञान एव धर्मः, नापि प्रयोग एव ॥

किं तर्हि ?

(९ ध्वनिः शब्दपक्षे सिद्धान्तवार्तिकम् ॥ ४ ॥)

॥ * ॥ शास्त्रपूर्वके प्रयोगेऽभ्युदयस्तत्तुल्यं वेदशब्देन ॥ * ॥

(भाष्यम्)

शास्त्रपूर्वकं यः शब्दान्प्रयुङ्क्ते सोऽभ्युदयेन युज्यते । 'तत्तुल्यं वेदशब्देन' । वेदशब्दा अप्येवमभिवदन्ति—"योऽग्निष्टोमेन यजते य उ चैनमेवं वेद", "योऽग्निं नाचिकेतं चिनुते य उ चैनमेवं वेद" ॥

(प्रदीपः) तत्तुल्यमिति । वेदः शब्दो यस्यार्थस्य सः—वेदशब्दः, तस्य यथा ज्ञात्वाऽनुष्ठानं तथा शब्दानामपि प्रकृत्यादिविभागज्ञानपूर्वकः प्रयोग इत्यर्थः ॥

(उद्द्योतः) शास्त्रपूर्वके इति । व्याकरणाध्ययनपूर्वके इत्यर्थः ॥ तत्र वेदाङ्गत्वादेतद्व्याकरणाध्ययनपूर्वकप्रयोगे एव धर्म इति प्रामाणिकाः ॥ वेदः शब्द इति । बोधक इत्यर्थः । प्रमाणमित्यर्थो वा ॥ तस्य यथेति । तस्य यथा 'य उ चैनमेवं वेद' इति ग्रन्थेन वेदतो ज्ञात्वाऽनुष्ठानं फलायोक्तम्, तथाऽस्यापि शास्त्रज्ञानपूर्वकप्रयोगः फलायेति 'एकः शब्दः' इत्यादिनोक्तमित्यर्थः ॥

(व्याख्यान्तरभाष्यम्)

अपर आह—

तत्तुल्यं वेदशब्देन—इति ।

यथा—वेदशब्दा नियमपूर्वमधीताः फलवन्तो भवन्ति, एवं यः शास्त्रपूर्वकं शब्दान्प्रयुङ्क्ते सोऽभ्युदयेन युज्यत इति ॥

(प्रदीपः) अपर आहेति । वेदश्चासौ शब्दश्च—वेदशब्द इति कर्मधारयः ॥

(सिद्धान्तभाष्यम्)

अथ वा पुनरस्तु—

ज्ञान एव धर्म इति ॥

(आक्षेपस्मारणभाष्यम्)

ननु चोक्तम्-*ज्ञाने धर्म इति चेत्तथाऽधर्मः* इति ॥

(आक्षेपनिराकरणभाष्यम्)

नैष दोषः, शब्दप्रमाणका वयम्, यच्छब्द आह तदस्माकं प्रमाणम् । शब्दश्च शब्दज्ञाने धर्ममाह, नापशब्दज्ञानेऽधर्मम् ॥ यच्च पुनरशिष्टाप्रतिषिद्धम्,

नैव तद्दोषाय भवति, नाभ्युदयाय । तद्यथा—हिक्कितहसितकण्डूयितानि नैव दोषाय भवन्ति, नाभ्युदयाय ॥

(उद्द्योतः) भाष्ये-प्रमाणमिति । प्रामाणिकमित्यर्थः ॥ शब्दश्च शब्दज्ञाने इति । 'एकः शब्दः सम्यक् ज्ञातः' इत्यादिः ॥ 'हेलयो हेलयः' इत्यादि तु अपशब्दप्रयोगेऽधर्ममाह, न तु ज्ञाने इति भावः ॥ यद्यपि तत्र 'प्रयुक्तः' इत्यप्युक्तं, तथाप्यवैयाकरणस्य सम्यक्प्रयोगादपि धर्माभावेन ज्ञानमेव तद्धेतुः । प्रयोगस्तु तस्य द्वारमिति भावः ॥

(समाधानान्तरभाष्यम्)

अथवाऽभ्युपाय एवापशब्दज्ञानं शब्दज्ञाने । यो ह्यपशब्दाञ्जानाति शब्दानप्यसौ जानाति । तदेवं 'ज्ञाने धर्मः' इति ब्रुवतोऽर्थादापन्नं भवति—'अपशब्दज्ञानपूर्वके शब्दज्ञाने धर्मः' इति ॥

(प्रदीपः) अथवेति । अपशब्दज्ञाननान्तरीयकत्वाच्छब्दज्ञानस्य पृथक्फलमपशब्दज्ञानस्य नास्तीत्यर्थः ॥

(उद्द्योतः) भाष्ये-अभ्युपाय एवेति । अपशब्दज्ञाननान्तरीयकं शब्दज्ञानमिति शब्दज्ञानेन फले जननीये सहकारितैवापशब्दज्ञानस्य, न पृथक्फलतेति भावः ॥ अपशब्दज्ञानम्-अपशब्दत्वेन तज्ज्ञानम् ॥ एवं 'शब्दज्ञाने' इत्यपि ॥ अपशब्दत्वेन तज्ज्ञाने हि तद्भिन्नत्वेन शब्दज्ञानं भवति ॥ 'यो हि' इति भाष्यस्य य एव अपशब्दान् जानाति असावेव शब्दान् जानातीति तज्ज्ञानसमानाधिकरणशब्दज्ञानादेव धर्म इति न ततो विपरीतफलकल्पना युक्तेति भावः ॥ तदाह—अपशब्दज्ञाननान्तरीयकत्वादिति । बहुव्रीहिः । न हि वह्न्यानयननान्तरीयकं पात्रानयनं ततः पृथक्फलं भवति ॥

(समाधानान्तरे न्यायदर्शकभाष्यम्)

अथवा कूपखानकवदेतद्भविष्यति । तद्यथा—कूपखानकः कूपं खनन्यद्यपि मृदा पांशुभिश्चावकीर्णो भवति सोऽप्सु संजातासु तत एव तं गुणमासादयति, येन स च दोषो निर्हण्यते भूयसा चाभ्युदयेन योगो भवति ॥ एवमिहापि यद्यपशब्दज्ञानेऽधर्मः, तथापि यस्त्वसौ शब्दज्ञाने धर्मस्तेन स च दोषो निर्घानिष्यते, भूयसा चाभ्युदयेन योगो भविष्यति ॥

(प्रदीपः) दोष इति । उत्कृष्टधर्मफलात्तासौ स्वल्पमधर्मफलमुत्पन्नमप्यनुत्पन्नकल्पं भवतीत्यर्थः ॥

(उद्द्योतः) 'तुष्यतु दुर्जनः' इति न्यायेनापशब्दज्ञानस्य विपरीतत्वमात्रेणाधर्मसाधनत्वमभ्युपगम्यापि भाष्ये समाधानान्तरमाह—अथवा कूपेति । मृत्-आर्द्रा । पांसुः-शुष्का । यत्कर्मनान्तरीयककर्मजन्यो यो विपरीतत्वमात्रेण कल्प्योऽवैधो दोषः स तत्कर्मजन्यफलनाश्यः, यथा कूपखनननान्तरीयकशरीरव्यापारजन्यो मृल्लेपस्तत्फलजलनाश्य इति सामान्यतो दृष्टानुमानात्तन्नाशानुमानमिति बोध्यम् ॥ उत्कृष्टधर्मेति । धर्मस्य विधिबोध्यत्वादुत्कृष्टत्वम् । अधर्मस्य तु वचनाबोध्यत्वेन विपरीतत्वमात्रेण कल्प्यस्याल्पत्वेन तत्फलधर्मनाश्यत्वम् ॥ यागीयहिंसायाः 'न हिंस्यात्' इतिवचनेन दुष्टतावोधनाद्दुष्टत्वमेवेत्यन्यत्र विस्तरः ॥

(द्वितीयदूषणनिरासभाष्यम्)

यदप्युच्यते—*आचारे नियमः* इति ।

याज्ञे कर्मणि स नियमः, अन्यत्रानियमः । एवं हि श्रूयते—'यर्वाणस्तर्वाणो नाम ऋषयो बभूवुः प्रत्यक्षधर्माणः परापरज्ञा विदितवेदितव्या अधिगतयाथातथ्याः ।' ते तत्रभवन्तः 'यद्वा नः' 'तद्वा नः' इति प्रयोक्तव्ये 'यर्वाणः-तर्वाणः' इति प्रयुञ्जते, याज्ञे पुनः कर्मणि नापभाषन्ते ॥ तैः पुनरसुरैर्याज्ञे कर्मण्यपभाषितम्, ततस्ते पराभूताः ॥

(प्रदीपः) प्रत्यक्षधर्माण इति । योगिप्रत्यक्षेण सर्वं विदितवन्तः ॥ परापरज्ञाः-विद्याऽविद्याप्रविभागज्ञाः ॥

(उद्द्योतः) भाष्ये-अन्यत्रानियम इति । यज्ञे सुशब्दप्रयोगाद्धर्मः-अपशब्दप्रयोगादधर्म इति तत्रैव तयोः प्रयोगनियमः । तदतिरिक्तस्थले तु सुशब्दापशब्दयोः प्रयोगेऽनियमः । योऽपि यज्ञे दोषः सोऽपि तदङ्गभूतसंकल्पोह्लादिविषये एव । श्रुतौ 'हेलयो हेलयो नश्यध्वं' इत्यूह एव ॥ विदितवेदितव्याः-इत्यनेन श्रवणमनननिदिध्यासनसंपदुक्ता ॥ अधिगतयाथातथ्याः-इत्यनेन साक्षात्कार उक्तः । याथातथ्यं प्रयुञ्जते-इति वर्तमानसमीपे भूते लट् । एवं 'नापभाषन्ते' इत्यपि । अत एव तन्नामानो बभूवुरित्यर्थः । स्वार्थे ष्यञ् । वेदितव्यस्य यथयथा तथा स्वरूपं शुद्धचिदानन्दरूपं तदधिगतं-प्रत्यक्षेण प्राप्तं यैरित्यर्थः ॥ याज्ञे पुनरिति । अनेन तत्त्वज्ञानामपि कर्माधिकारं सूचयति ॥

इति शब्दज्ञानस्य धर्मजनकताधिकरणम् ।

(अथ व्याकरणाधिकरणम्)

(व्याकरणपदार्थोपन्यासभाष्यम्)

अथ व्याकरणमित्यस्य शब्दस्य कः पदार्थः ? सूत्रम् ॥

(प्रदीपः) अथेति । उक्तमिदं-न चान्तरेण व्याकरणं-इत्यादि । तत्र पक्षद्वयेऽपि दोषदर्शनात् पदार्थप्रश्नः ॥

(उद्द्योतः) व्याकरणपदार्थविचारस्य सङ्गतिं दर्शयितुमाह—उक्तमिदमिति । आदिना 'तस्मादध्येयं व्याकरणं' इत्यादि पुनः पुनरुक्तिर्गृह्यते ॥

(१० आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ सूत्रे व्याकरणे षष्ठ्यर्थोऽनुपपन्नः ॥ * ॥

(भाष्यम्)

सूत्रे व्याकरणे षष्ठ्यर्थो नोपपद्यते—'व्याकरणस्य सूत्रम्' इति ॥ किं हि तदन्यत्सूत्रात् व्याकरणं यस्यादः सूत्रं स्यात् ?

(प्रदीपः) **षष्ठ्यर्थ इति** । द्वाभ्यामपि शब्दाभ्यामष्टाध्याय्याः प्रतिपादनाद्व्यतिरेकाभावः । सामान्यविशेषशब्दतया तु द्वयोः प्रयोगो न विरुध्यते । यदा त्वष्टाध्याय्येकदेशः सूत्रशब्देनोच्यते, तदा षष्ठ्यर्थोऽप्युपपद्यते ॥

(उद्द्योतः) ननु सूत्रसमुदायस्य व्याकरणस्येदं सूत्रमित्युपपद्यतेऽत आह—**द्वाभ्यामिति** । सूत्रपदेनाप्यष्टाध्याय्येव यदोच्यते तदापीष्यतेऽयं प्रयोगः, स न सिध्येदित्यर्थः ॥ ननु किमुच्यते—'षष्ठ्यर्थोऽनुपपन्नः' इति, पर्यायतया सहप्रयोगोऽपि न स्यादत आह—**सामान्यविशेषेति** । सूत्रं सामान्यं, व्याकरणं विशेषः । सूत्रशब्देनाष्टाध्याय्येव, तदेकदेशे तु योगव्यवहार एव '**योगे योगे उपतिष्ठते**' इत्यादौ ॥ **यदा त्विति** । '**सूत्राणि चाप्यधीयाने**' इति भाष्ये वक्ष्यमाणत्वादिति भावः । वस्तुत एकदेशस्य सूत्रत्वेऽपि तस्यापि साक्षात्परम्परया वा व्याकरणत्वात्षष्ठ्यर्थानुपपत्तिरेवेति तत्त्वम् ॥

(११ आक्षेपान्तरवार्तिकम् ॥ २ ॥)

॥ * ॥ शब्दाप्रतिपत्तिः ॥ * ॥

(भाष्यम्)

शब्दानां चाप्रतिपत्तिः प्राप्नोति—'व्याकरणाच्छब्दान्प्रतिपद्यामहे' इति । न हि सूत्रत एव शब्दान्प्रतिपद्यन्ते ।

किं तर्हि ?

व्याख्यानतश्च ॥

(प्रदीपः) **शब्दाप्रतिपत्तिरिति** । न हि व्याख्यानरहितसूत्रमात्रश्रवणाच्छब्दाः प्रतीयन्ते ॥

(उद्द्योतः) समुदायस्यातिरिक्तत्वेऽपि दोषमाह—**भाष्ये—शब्दाप्रतिपत्तिरिति** । व्याकरणाच्छब्दान्प्रतिपद्यामह इति शब्दविषयव्यवहारासिद्धिः प्राप्नोतीत्यर्थः । यतः केवलसूत्रेभ्यः शब्दप्रतिपत्तिर्न दृश्यते । व्याकरणस्य शब्दप्रतिपत्तिहेतुत्वं च लोकसिद्धम्, व्याकरणाच्छब्दान्प्रतिपद्यामह इति व्यवहारात् । सेयं प्रतिपत्तिसाधनता सूत्राद्व्यावर्तमाना तद्व्याप्यां व्याकरणशब्दवाच्यतां व्यावर्तयतीति भावः । तदाह—**न हीति** ॥

(आक्षेपबाधकभाष्यम्)

ननु च तदेव सूत्रं विगृहीतं व्याख्यानं भवति ॥

(आक्षेपसाधकभाष्यम्)

न केवलं चर्चापदानि व्याख्यानम्-'वृद्धिः, आत्, ऐच्' इति ।

किं तर्हि ?

उदाहरणं-प्रत्युदाहरणं-वाक्याध्याहारः-इत्येतत्समुदितं व्याख्यानं भवति ॥

(प्रदीपः) **समुदितमिति** । समुदायादेवार्थावसायोत्पादादित्यर्थः ॥

(उद्द्योतः) भाष्ये—**चर्चापदानि**—चर्च्यमानानि—विभज्यमानानीत्यर्थः ॥ **वाक्याध्याहार इति** । वाक्यघटकपदानां सूत्रान्तरे श्रुतानां स्वरितत्वप्रतिज्ञयाऽध्याहारः—कल्पनमित्यर्थः । यद्वा **वाक्याध्याहार** इत्यनेन वार्तिककृद्व्याख्यानां सूत्रतात्पर्यविषयता वाक्यैकदेशन्यायेन सूचिता ॥

(पक्षान्तरोपस्थापकं भाष्यम्)

एवं तर्हि शब्दः ।

(उद्द्योतः) **शब्द इति** । लक्ष्यमित्यर्थः । अत्र पक्षे षष्ठ्यर्थ उपपद्यते । शब्दाप्रतिपत्तिहेतुता तु तदवस्था ॥

(१२ शब्दो व्याकरणमिति पक्षे आक्षेपवार्तिकम् ॥ ३ ॥)

॥ * ॥ शब्दे ल्युडर्थः ॥ * ॥

(भाष्यम्)

यदि शब्दो व्याकरणं ल्युडर्थो नोपपद्यते—व्याक्रियन्ते शब्दा अनेनेति व्याकरणम् । न हि शब्देन किंचित् व्याक्रियते ।

केन तर्हि ?

सूत्रेण ॥

(प्रदीपः) **शब्द इति** । करणे ल्युड्विधीयते । शब्दश्च व्याक्रियमाणत्वात्कर्म, न तु करणमिति भावः ॥

(उद्द्योतः) ननु राजभोजना इतिवत् कर्मल्युटि न दोषोऽत आह—**करणे इति** । कर्मणि स तु क्वाचित्क इति भावः ॥

(१३ आक्षेपान्तरवार्तिकम् ॥ ४ ॥)

॥ * ॥ भवे च तद्धितः ॥ * ॥

(भाष्यम्)

भवे च तद्धितो नोपपद्यते—व्याकरणे भवो योगो वैयाकरणः-इति । नहि शब्दे भवो योगः ।

क तर्हि ?

सूत्रे ॥

(प्रदीपः) **भवे चेति** । शब्देऽप्यन्वाख्यायकत्वेन भवो योग इति चेत्, मीमांसकादियोगस्यापि शब्दं प्रति विचारकत्वात् वैयाकरणत्वप्रसङ्गः ॥

(१४ आक्षेपान्तरवार्तिकम् ॥ ५ ॥)

॥ * ॥ प्रोक्तादयश्च तद्धिताः ॥ * ॥

(भाष्यम्)

प्रोक्तादयश्च तद्धिता नोपपद्यन्ते । पाणिनिना प्रोक्तं पाणिनीयम्, आपिशलं, काशकृत्स्नमिति । न हि पाणिनिना शब्दाः प्रोक्ताः ।

किं तर्हि

सूत्रम् ॥

(वार्तिकप्रणयनाक्षेपभाष्यम्)

किमर्थमिदमुभयमुच्यते— * भवे-प्रोक्तादयश्च

तद्धिताः* इति । न *प्रोक्तादयश्च तद्धिताः* इत्येव भवेऽपि तद्धितश्चोदितः स्यात् ?

(समाधानभाष्यम्)

पुरस्तादिदमाचार्येण दृष्टम्—*भवे च तद्धितः* इति, तत्पठितम् । तत उत्तरकालमिदं दृष्टम्-*प्रोक्तादयश्च तद्धिताः* इति, तदपि पठितम् । न चेदानीमाचार्याः सूत्राणि कृत्वा निवर्तयन्ति ॥

(प्रदीपः) न चेदानीमिति । लक्षणप्रपञ्चाभ्यां मूलसूत्रवत् वार्तिकानामुपपत्त्या दोषाभावः ॥

(उद्योतः) लक्षणप्रपञ्चाभ्यामिति । यथा—कर्मधारयप्रकरणे, अलुक्प्रकरणे च । विजिगीषुकथायां हि अभिहिताभिधानमशक्तिसूचकत्वाद्दोषाय । इह तु व्युत्पादनार्थत्वान्न दोषकृदिति भावः ॥ पूर्वं सामान्ये उक्ते पश्चाद्विशेषकथनं प्रपञ्चार्थमिति युज्यते, अत्र तु विपरीतमिति न तत्साम्यमित्यन्ये ॥

(प्रथमाक्षेपबाधकभाष्यम्)

अयं तावददोषः—यदुच्यते *शब्दे ल्युडर्थः* इति । नावश्यं करणाधिकरणयोरेव ल्युड्विधीयते । किं तर्हि ?

अन्येष्वपि कारकेषु—"कृत्यल्युटो बहुलम्" इति । तद्यथा-प्रस्कन्दनं प्रपतनमिति ॥

(प्रदीपः) प्रस्कन्दनमिति । यद्यप्ययं भीमादिः, तथापि 'कृत्यल्युटो बहुलम्' इत्यस्यैव 'भीमादयोऽपादाने' इत्ययं प्रपञ्च इति भावः ॥

(करणल्युट्समर्थनभाष्यम्)

अथवा शब्दैरपि शब्दा व्याक्रियन्ते । तद्यथा-गौरित्युक्ते सर्वे संदेहा निवर्तन्ते, नाश्वो न गर्दभ इति ॥

(प्रदीपः) गौरित्युक्त इति । सास्नादिमति यदा कंचित्प्रति 'अयं गौः' इत्युच्यते तदाऽत्र वाचकान्तराणां निवृत्तिः कृता भवति, एवमेकस्मिन्नुदाहरणे उपन्यस्ते सर्वाणि तत्सदृशानि शब्दान्तराणि प्रतीयन्ते ॥

(उद्योतः) प्रतीयन्त इति । एवं च विपरीतव्यावृत्तिः सदृशसंग्रहश्च व्याकृतिरिति भावः ॥ एतेन शब्दाप्रतिपत्तिरप्यत्र पक्षे उद्धृता ॥

(अनुद्धृतदोषप्रदर्शकभाष्यम्)

अयं तर्हि दोषः—*'भवे-प्रोक्तादयश्च तद्धिताः'* इति ॥

(समाधानोपक्रमभाष्यम्)

एवं तर्हि—

(१५ सिद्धान्तवार्तिकम् ॥ ६ ॥)

॥ * ॥ लक्ष्यलक्षणे व्याकरणम् ॥ * ॥

(भाष्यम्)

लक्ष्यं च लक्षणं चैतत्समुदितं व्याकरणं भवति ॥ किं पुनर्लक्ष्यम्, किं लक्षणम् ? शब्दो लक्ष्यः, सूत्रं लक्षणम् ॥

(उद्योतः) व्यावर्त्यव्यावर्तकरूपलक्ष्यलक्षणस्यातिप्रसक्तत्वात्पृच्छति— भाष्ये- किं पुनरिति ॥

(समाधानबाधकभाष्यम्)

एवमप्ययं दोषः—समुदाये व्याकरणशब्दः प्रवृत्तोऽवयवे नोपपद्यते । सूत्राणि चाप्यधीयान इष्यते—वैयाकरण इति ॥

(समाधानसाधकभाष्यम्)

नैष दोषः । समुदायेषु हि शब्दाः प्रवृत्ता अवयवेष्वपि वर्तन्ते । तद्यथा-पूर्वे पञ्चालाः, उत्तरे पञ्चालाः, तैलं भुक्तम्, घृतं भुक्तम्, शुक्लो नीलः कृष्ण इति ॥

एवमयं समुदाये व्याकरणशब्दः प्रवृत्तोऽवयवेऽपि वर्तते ॥

(प्रदीप) पूर्वे पञ्चाला इति । जनपदान्तरानिवृत्तिविवक्षायामेकदेशेऽपि समुदायरूपारोपात्प्रयोगः ॥ तैलमिति । यदौषधसंस्कृता घृततैलमात्रा भवति तदैतदुदाहरणम् । आकृतिवाचित्वे तु घृततैलशब्दयोः संस्थानप्रमाणनिरपेक्षा सर्वत्र मुख्या वृत्तिः ॥ शुक्ल इति । अशुक्लेऽप्यवयवेऽवयवान्तरस्य शौक्ल्यात्समुदायस्य शुक्लत्वे सति आरोपात्प्रयोगः ॥

(उद्योतः) जनपदान्तरेति । भावप्रधानो निर्देशः ॥ यदेति । मात्रा—परिच्छिन्नोंऽशः । औषधसंस्कृते तत्र समुदाये घृतादिशब्दस्य रूढिरिति भावः ॥ अशुक्लेऽप्यवयवे इति । 'प्रयोगः' इत्यनेनान्वेति ॥ आरोपादिति । समुदायस्य शुक्लत्वे अशुक्लावयवे प्रयोगे च हेतुः । तत्र समुदाये शुक्लत्वारोपे हेतुः 'अवयवान्तरस्य शौक्ल्यात्' इति । वनैकदेशे 'पुष्पितं वनम्' इतिवदेकदेशेऽपि शुक्ले 'शुक्लः पटः' इति व्यवहार इति बोध्यम् ॥

(प्रथमपक्षाभ्युपगमभाष्यम्)

अथ वा पुनरस्तु सूत्रम् ॥

(प्रथमाक्षेपस्मारणभाष्यम्)

ननु चोक्तम्-*सूत्रे व्याकरणे षष्ठ्यर्थोऽनुपपन्नः* इति ॥

(प्रथमाक्षेपनिरासभाष्यम्)

नैष दोषः । व्यपदेशिवद्भावेन भविष्यति ॥

(प्रदीपः) व्यपदेशिवद्भावेनेति । यथा 'राहोः शिरः' इत्येकस्मिन्नपि वस्तुनि शब्दार्थभेदाद्भेदव्यवहारः, एवमिहापि व्याकरणशब्देन शास्त्रस्य व्याकृतिक्रियायां करणरूपत्वमुच्यते । सूत्रशब्देन तु समुदायरूपता—इति भेदव्यवहार उपपद्यते ॥

(उद्योतः) शब्दार्थभेदादिति । अनेकावस्थायुक्तं शिरो राहुशब्दार्थः, यत्किंचिदेकावस्थायुक्तं तत् शिरःशब्दार्थः । तादृशराहुशब्दार्थस्य तादृशशिरःपदार्थोऽवयव इति षष्ठ्यर्थोपपत्तिरिति भावः ॥ सूत्रशब्देन तु समुदायरूपतेति । अनेकावस्थायुक्तस्य तस्य व्याकृतिक्रियाकरणावस्थाविशिष्टमवयव इति तद्रूपावयवस्यायं समुदाय इत्यर्थः ॥ ईदृशे स्थले विकल्पात्मकं ज्ञानं वस्तुशून्यमेव, व्यपदेशिवद्भावविषयेऽप्येवमेव, "शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः" इति योगसूत्रे पतञ्जलिसूत्रकारैरित्यन्ये ॥

(द्वितीयाक्षेपस्मारणभाष्यम्)

यदप्युच्यते—'*शब्दाप्रतिपत्तिः'*इति । न हि सूत्रत एव शब्दान्प्रतिपद्यन्ते । किं तर्हि? व्याख्यानतश्च-इति । परिहृतमेतत्—तदेव सूत्रं विगृहीतं व्याख्यानं भवतीति ॥

(परिहारबाधकस्मारणभाष्यम्)

ननु चोक्तम्—"न केवलानि चर्चापदानि व्याख्यानम्—वृद्धिः—आत्-ऐजिति । किं तर्हि? उदाहरणं-प्रत्युदाहरणं-वाक्याध्याहारः—इत्येतत्समुदितं व्याख्यानं भवति" इति ॥

(परिहारसाधकभाष्यम्)

अविजानत एतदेवं भवति । सूत्रत एव हि शब्दान् प्रतिपद्यन्ते ॥

आतश्च सूत्रत एव । यो ह्युत्सूत्रं कथयेन्नादो गृह्येत ॥

(प्रदीपः) सूत्रत एवेति । पदच्छेदादिभिः सूत्रार्थस्यैवाभिव्यञ्जनात् ॥

आत इति । निपातः । अतश्च हेतोरित्यर्थः ॥ नाद इति । नैतदित्यर्थः ॥ अथवा नादोऽर्थरहितत्वान् घोषमात्रमेव गृह्येतत्यर्थः ॥

(उद्द्योतः) भाष्ये—अविजानत इति । मन्दबुद्धेरित्यर्थः ॥ सूत्रत एवेति । एतन्मूलकमेव पठ्यते—

"सूत्रेष्वेव हि तत्सर्वं यद्वृत्तौ यच्च वार्त्तिके ।" इति ॥

(इति व्याकरणाधिकरणम् ॥)

(अथ वर्णोपदेशाधिकरणम्)

(आक्षेपभाष्यम्)

अथ किमर्थो वर्णानामुपदेशः?

(प्रदीपः) किमर्थ इति । न हि वर्णोपदेशेन कस्यचित्साधुशब्दस्यानुशासनमिति भावः ॥

(उद्द्योतः) ननु लोकप्रसिद्धमातृकापाठेनैव वर्णज्ञानसंभवान्माहेश्वरो वर्णसमाम्नायः किमर्थ इति पृच्छति—भाष्ये-किमर्थ इति । पाणिनये महादेवकृत इत्यर्थः ॥ ननु साधुत्वान्वाख्यानं फलमत आह—न हीति ॥

(१६ समाधानवार्तिकम् ॥ १ ॥)

॥ * ॥ वृत्तिसमवायार्थ उपदेशः ॥ * ॥

(भाष्यम्)

वृत्तिसमवायार्थो वर्णानामुपदेशः कर्तव्यः । किमिदं वृत्तिसमवायार्थ इति? वृत्तये समवायः-वृत्तिसमवायः । वृत्त्यर्थो वा समवायः-वृत्तिसमवायः । वृत्तिप्रयोजनो वा समवायः-वृत्तिसमवायः ॥

का पुनर्वृत्तिः? शास्त्रप्रवृत्तिः ॥

अथ कः समवायः? वर्णानामानुपूर्व्येण संनिवेशः॥

अथ क उपदेशः? उच्चारणम् ॥

कुत एतत्? दिशिरुच्चारणक्रियः । उच्चार्य हि वर्णानाह—उपदिष्टा इमे वर्णा इति ॥

(प्रदीपः) वृत्तिसमवायार्थ इति । लाघवेन शास्त्रप्रवृत्त्यर्थं इत्यर्थः । धर्मनियमवत्समासः ॥ वृत्त्यर्थ इति । शास्त्रप्रवृत्तिप्रत्यासन्नत्वं समवायस्य दर्शयति-'इग्यणः'इत्यादौ हि यथासंख्यशास्त्रं वर्णसंनिवेशमात्रादेवावतिष्ठते ॥ वृत्तिप्रयोजन इति । पारम्पर्येण शास्त्रप्रवृत्तावस्याङ्गत्वम् । सति हि समवाये इत्संज्ञा, ततः 'आदिरन्त्येन-' इति, ततः 'हलोपे-'इत्यादिशास्त्रप्रवृत्तिः ।

(उद्द्योतः) उत्तरम्—वृत्तिसमवायार्थ इति । वृत्तिः=शास्त्रप्रवृत्तिः, तदुपयोगी समवायो वर्णगतः क्रमविशेषः, स बोध्यत्वेनार्थः प्रयोजनं यस्य सः-तथोक्तः । सति ह्यक्षरसमाम्नायेऽजादिसंज्ञाभिर्लाघवेन शास्त्रप्रवृत्तिः, 'इग्यणः' इत्यादौ यथासङ्ख्यप्रवृत्तिश्चेति भावः । अनेनास्य शास्त्रबहिर्भूतत्वं सूचितम् । अत एव 'मङ्गलार्थं महतः शास्त्रौघस्यादितो वृद्धिशब्दं पठति' इति वक्ष्यति । अन्यकर्तृकत्वं च सूचितम् । 'पाणिनिशास्त्रप्रवृत्त्यर्थं उपदेशः' इत्युक्ते उपदेशे गुरुकर्तृकतायाः स्वरसतः प्रतीतेः, सिद्धोच्चारणेऽपि मन्त्रोपदेश इत्यादावुपदेशव्यवहारात् । 'अनुबन्धकरणार्थः' इत्यत्र करणपदेनेतरस्य सिद्धत्वसूचनात् । तत्करणं चोपदेशकर्तृकर्तृकमेव प्रत्यासत्तेरित्याहुः ॥ भाष्ये—किमिदमिति । कोऽयं समास इति प्रश्नः ॥ धर्मनियमवदिति । षष्ठीसमासः ॥ पक्षत्रयभेदमुपपादयति—शास्त्रेति । आद्यतात्पर्यं सूक्तं-'लाघवेन शास्त्रप्रवृत्त्यर्थः' इति ॥ ननु नेदमाद्योच्चारणम्, अस्यानादित्वात्; तत्कथमुपदेशत्वव्यवहारोऽत आह—भाष्ये—उच्चारणमिति । ढक्कानिनादेनाभिव्यक्तिरित्यर्थः ॥

(१७ वर्णोपदेशप्रयोजनान्तरवार्तिकम् ॥ २ ॥)

॥ * ॥ अनुबन्धकरणार्थश्च ॥ * ॥

(भाष्यम्)

अनुबन्धकरणार्थश्च वर्णानामुपदेशः कर्तव्यः । अनुबन्धानासङ्क्ष्यामीति । न ह्यनुपदिश्य वर्णाननुबन्धाः शक्या आसङ्क्तुम् ॥

स एष वर्णानामुपदेशो वृत्तिसमवायार्थश्चानुबन्धकरणार्थश्च ।

वृत्तिसमवायश्चानुबन्धकरणं च प्रत्याहारार्थम् । प्रत्याहारो वृत्त्यर्थः ॥

(प्रदीपः) प्रत्याहारार्थमिति । प्रत्याहारशब्देनाणादिकाः संज्ञा उच्यन्ते ॥

(उद्द्योतः) फलान्तरमाह—भाष्ये—अनुबन्धकरणार्थश्चेति । अनुबन्धबोधनार्थ इत्यर्थः । येनाकारस्य विवृतगुणत्वसंग्रहः, उपलक्षणत्वेन वा । अनुबन्धत्वं च समुदायान्त्यत्वे सति, नान्यथेति तात्पर्यम् ॥ ननु प्रत्याहारशब्देन सूत्रं चेत् तादर्थ्यमनुबन्धानामनुपपन्नमत आह—प्रत्याहारशब्देनेति । अधिकरणल्युत्पत्त्या, अणु-

आपद्या वेति भावः ॥ भाष्ये—वृत्त्यर्थं इति । लाघवेन शास्त्रप्रवृत्त्यर्थं इत्यर्थः ॥ एतेन प्रत्याहारद्वारा संव्यायस्य वृत्त्यर्थता दर्शिता ॥

(वार्तिकावतरणभाष्यम्)

इष्टबुद्ध्यर्थश्च वर्णानामुपदेशः ।

'इष्टान्वर्णान् भोत्स्यामहे' इति । न ह्यनुपदिश्य वर्णानिष्टा वर्णाः शक्या विज्ञातुम् ॥

(प्रदीपः) इष्टबुद्ध्यर्थश्चेति । सति ह्युपदेशे कलादिदोषरहिता ये वर्णा निर्दिष्टास्ते तथैव प्रयोक्तव्या इत्युक्तं भवति ॥

(उद्द्योतः) भोत्स्यामहे इति । अन्तर्भावितण्यर्थः, बोधयिष्यामह इत्यर्थः ॥ एवं 'विज्ञातुं'इत्यस्य ज्ञापयितुमित्यर्थः ॥ सति ह्युपदेशे इति । एवं च व्याकरणाध्येनणामक्षरसमाम्नायेनैवावश्यकेनेष्टवर्णज्ञाने सिद्धे न तदर्थं मातृका पाठनीयेति भावः ॥

(१८ आक्षेपवार्तिकम् ॥ ३ ॥)

॥ * ॥ इष्टबुद्ध्यर्थश्चेति चेदुदात्तानुदात्तस्वरितानुनासिकदीर्घप्लुतानामप्युपदेशः ॥ * ॥

(भाष्यम्)

इष्टबुद्ध्यर्थश्चेति चेदुदात्तानुदात्तस्वरितानुनासिकदीर्घप्लुतानामप्युपदेशः कर्तव्यः । एवंगुणा अपि हि वर्णा इष्यन्ते ॥

(प्रदीपः) एकश्रुत्या सूत्राणां पाठात्सर्वेषामुदात्तादीनामुपदेशः कर्तव्य इत्याह—इष्टबुद्ध्यर्थश्चेति चेदिति ।

(उद्द्योतः) एकश्रुत्येति । त्रैस्वर्यपाठे तु द्वयोरेव कर्तव्यतां वदेदित्यर्थः । तेषां लोकतः सिद्धौ तु दोषरहितानामपि तत एव सिद्धेरुपदेशवैयर्थ्यापत्तिरिति भावः ॥ त्रैस्वर्येण पाठेऽपि अन्यतमपाठेऽन्यस्य कर्तव्यत्वाभिप्रायेण सर्वेषां ग्रहणमित्यन्ये ॥

(१९ सिद्धान्तवार्तिकम् ॥ ४ ॥)

॥ * ॥ आकृत्युपदेशात्सिद्धम् ॥ * ॥

(भाष्यम्)

आकृत्युपदेशात्सिद्धमेतत् । अवर्णाकृतिरुपदिष्टा सर्वमवर्णकुलं ग्रहीष्यति । तथेवर्णाकृतिः । तथोवर्णाकृतिः ॥

(प्रदीपः) आकृत्युपदेशादिति । उपात्तोऽपि विशेषो नान्तरीयकत्वाज्जातिप्राधान्यविवक्षायां न विवक्ष्यत इत्यर्थः ॥

(उद्द्योतः) आकृत्युपदेशे किमिति अकारादिह्रस्वव्यक्तिविशेषोपादानं, तदुपादाने व्यक्त्यन्तरग्रहणानापत्तिश्चेत्यत आह—उपात्त इति । नान्तरीयकत्वं च तं विना जातेरुच्चारयितुमशक्यत्वात् ॥

(२० आक्षेपवार्तिकम् ॥ ५ ॥)

॥ * ॥ आकृत्युपदेशात्सिद्धमिति चेत् संवृतादीनां प्रतिषेधः ॥ * ॥

(भाष्यम्)

आकृत्युपदेशात्सिद्धमिति चेत् संवृतादीनां प्रतिषेधो वक्तव्यः ॥

के पुनः संवृतादयः ?

संवृतः, कलः, ध्मातः, एणीकृतः, अम्बूकृतः, अर्धकः, ग्रस्तः, निरस्तः, प्रगीतः, उपगीतः, क्ष्विण्णः, रोमशः-इति ॥

अपर आह—

"ग्रस्तं निरस्तमवलम्बितं निर्हतमम्बूकृतं ध्मातमथो विकम्पितम् ।
संदष्टमेणीकृतमर्धकं द्रुतं विकीर्णमेताः स्वरदोषभावनाः ॥" इति ।

अतोऽन्ये व्यञ्जनदोषाः ॥

(प्रदीपः) संवृतादीनामिति । आकारादीनां संवृतत्वं दोषः । न त्वकारस्य संवृतगुणत्वात् । तत्र संध्यक्षरेषु विवृततमेषूच्चार्येषु संवृतत्वं दोषः । कलः-स्थानान्तरनिष्पन्नः काकलित्वेन प्रसिद्धः । ध्मातः-श्वासभूयिष्ठतया ह्रस्वोऽपि दीर्घ इव लक्ष्यते । एणीकृतः-अविशिष्टः किमयमोकारोऽथौकार इति यत्र संदेहः । अम्बूकृतः-यो व्यक्तोऽप्यन्तर्मुखमिव श्रूयते । अर्धकः-दीर्घोऽपि ह्रस्व इव । ग्रस्तः-जिह्वामूले निगृहीतः, अव्यक्त इत्यपरे । निरस्तः-निष्ठुरः । प्रगीतः-सामवदुच्चारितः । उपगीतः-समीपवर्णान्तरगीत्यानुरक्तः । क्ष्विण्णः-कम्पमान इव । रोमशः-गम्भीरः । अवलम्बितः-वर्णान्तरसंभिन्नः । निर्हतः-रूक्षः । सन्दष्टः-वर्धित इव । विकीर्णः-वर्णान्तरे प्रसृतः, एकोऽप्यनेकनिर्भासीत्यपरे । स्वरदोषभावना इति । स्वरदोषगोत्राणि । अनन्ता हि दोषा अशक्तिप्रमादकृताः ॥

(उद्द्योतः) संवृतादीनामिति-भाष्ये-तादृशदोषसहितानामाकृतिग्रहणात्प्राप्तस्य ग्रहणस्य प्रतिषेधो वक्तव्य इत्यर्थः ॥ तदाह—एकारादीनां संवृतत्वमिति ॥ अविशिष्ट इति । संश्लिष्टः, संदिग्ध इति यावत् ॥ ह्रस्व इवेति । तद्वत्कालसङ्कोचेनोच्चारित इत्यर्थः ॥ निष्ठुर इति । त्वरित इत्यन्ये ॥ गोत्राणीति । स्वरदोषजातय इत्यर्थः ॥

(सिद्धान्तिभाष्यम्)

नैष दोषः ।

गर्गादिबिदादिपाठात्संवृतादीनां निवृत्तिर्भविष्यति ॥

(उद्द्योतः) भाष्ये—गर्गादिबिदादिपाठादिति । संवृतादिदोषरहितानामेव तत्र पाठादिति भावः ॥

(आक्षेपभाष्यम्)

अस्त्यन्यत् गर्गादिबिदादिपाठे प्रयोजनम् ॥ किम् ?

समुदायानां साधुत्वं यथा स्यादिति ॥

(प्रदीपः) अस्त्यन्यदिति । गर्ग इत्यादिनैव संनिवेशेन गर्गादीनां साधुत्वं यथा स्यात्, गार्ग्य इत्यादीनां मा भूत् । ततश्च तद्गतानामेवाकारादीनां दोषनिवृत्तिः कृता स्यात्, न तु समुदायान्तरस्थानाम् । यद्यपि प्रत्ययविध्यर्थो गर्गादीनां पाठस्तथापि प्रसङ्गात्समुदायसाधुत्वायापि भवति ॥

(उद्द्योतः) साधुत्वमिति । निवृत्तकलादिदोषवत्त्वमित्यर्थः ॥ गार्ग्य इत्यादीनामिति । तत्रत्यानां कलादिदोषनिवृत्तिर्न स्यादित्यर्थः । तदाह—ततश्चेति ॥ परे तु समुदायानां—एतत्प्रकृतिकप्रत्ययान्तसमुदायानां साधुत्वं यथा स्यादित्यर्थं पाठश्चरितार्थः, न कलादिदोषान्निवर्तयेदित्येव भाष्यार्थः । 'पाठश्चैव विशेष्यते' इत्यग्रिमभाष्यस्वरसादित्याहुः ॥

(समाधानैकदेशिभाष्यम्)

एवं तर्ह्यष्टादशधा भिन्नां निवृत्तकलादिकामवर्णस्य प्रत्यापत्तिं वक्ष्यामि ॥

(प्रदीपः) निवृत्तकलादिकामिति । अकारस्य संवृतत्वात् 'निवृत्तसंवृतत्वादिकाम्' इति नोक्तम् । अकारस्य निदर्शनार्थत्वात्सर्ववर्णानां शास्त्रान्ते प्रत्यापत्तिरित्यर्थः ॥

(उद्द्योतः) निदर्शनार्थत्वादिति । तत्रावर्णस्य 'अ-अ' इति कृतैव, तद्वत्तदनन्तरमन्येषामपि करिष्यामीति भावः ॥ एतेन अवर्णप्रतिपत्तेः कृतत्वात् 'वक्ष्यामि—इत्यनुपपन्नम्' इति परास्तम् ॥

(आक्षेपभाष्यम्)

सा तर्हि वक्तव्या ॥

(उद्द्योतः) भाष्ये—सा तर्हि वक्तव्येति । तथा च प्रत्यापत्त्याश्रयणे गौरवमिति भावः ॥

(२१ एकदेशिसमाधानवार्तिकम् ॥ ६ ॥)

॥ * ॥ लिङ्गार्था तु प्रत्यापत्तिः ॥ * ॥

(भाष्यम्)

लिङ्गार्था सा तर्हि भवति ॥

(उद्द्योतः) लिङ्गार्था त्विति । अनुबन्धस्थानीयतत्तद्भास्वादिगतकलादिलिङ्गनिवृत्त्यर्था—इत्यर्थः ॥ नाकृतिनिर्देशप्रयुक्तदोषपरिहारमात्रप्रयोजना प्रत्यापत्तिः, किं तु सर्वानुबन्धेत्संज्ञाशास्त्राद्यकरणफलिकाऽपीति न गौरवमिति भावः ॥

(आक्षेपभाष्यम्)

तर्हि वक्तव्यम् ॥

(उद्द्योतः) तदेव विवृणोति—तत्तर्हीत्यादिना । धात्वादिगतकलादिलिङ्गमित्यर्थः ॥

(समाधानभाष्यम्)

यद्यप्येतदुच्यते, अथवैतर्हि अनेकमनुबन्धशतं नोच्चार्यम्, इत्संज्ञा च न वक्तव्या, लोपश्च न वक्तव्यः । यदनुबन्धैः क्रियते तत्कलादिभिः करिष्यते ॥

(प्रदीपः) यदनुबन्धैरिति । यथा स्वरितत्वमधिकारार्थमेवमात्मनेपदार्थं कलादिकं प्रतिज्ञाय कलादात्मनेपदमित्यादि करिष्यते, न तु 'अनुदात्तङित:' इत्यादि ॥ नन्वनुबन्धाभावे कथमणादिकाः संज्ञा उपपद्यन्ते ? 'आदिः कलैः सह' इत्युक्त्वा 'अ-उ' इत्यादिकाः संज्ञाः करिष्यन्ते, स्वरसन्धिश्चासन्देहाय न करिष्यते—इत्यदोषः ॥

(उद्द्योतः) 'अथवैतर्हि' इत्यस्य तथापीत्यर्थः ॥ अनेकमनुबन्धशतमिति । एकैकस्यानुबन्धस्य शतश उच्चारणं, तादृशाश्चानेक उच्चारणीया इत्यर्थः ॥ यथेति । 'एध शी' इत्यादयोऽनुदात्तङितः कलदोषयुक्ताः पाठ्याः । स्वरितञितश्च ध्माताः । तत्र 'कलादात्मनेपदम्' 'ध्मातात्कर्तृगामिनि क्रियाफले' इति सूत्रे कार्ये । एवं टकितौ कलध्मातौ पठित्वा 'आद्यन्तौ कलध्मातौ' इति पाठ्यम् । एवं द्वितोऽर्द्धकदोषयुक्तान् पठित्वा 'अर्धकात् कित:' इति । ङितश्च ग्रस्तान्पठित्वा 'ग्रस्तादथुच्' इत्यादि बोध्यम् । एते च कलादयः प्रक्रियादशायामेव । प्रयोगे तु शुद्ध एव, शास्त्रान्ते प्रत्यापत्तिकरणात् । 'आदिः कलैः सह' इति पाठः ॥

(आक्षेपभाष्यम्)

सिध्यत्येवम् । अपाणिनीयं तु भवति ॥

(उद्द्योतः) भाष्ये—अपाणिनीयमिति । वर्णसमाम्नायसमर्थनाय प्रवृत्तस्य एकदोषपरिहाराय सकलशास्त्रस्य व्याख्यानसापेक्षगुरुप्रकारेणान्यथाकरणे 'वृश्चिकभिया'इत्यादिन्याय आपततीति भावः ॥

(सिद्धान्तिभाष्यम्)

यथान्यासमेवास्तु ॥

(आक्षेपस्मारणभाष्यम्)

ननु चोक्तम्—*आकृत्युपदेशात्सिद्धमिति चेत्संवृतादीनां प्रतिषेधः* इति ॥

(समाधानभाष्यम्)

परिहृतमेतत्—गर्गादिबिदादिपाठात् संवृतादीनां निवृत्तिर्भविष्यति—इति ॥

(समाधानबाधकभाष्यम्)

ननु चान्यत् गर्गादिबिदादिपाठे प्रयोजनमुक्तम् ।

किम् ?

समुदायानां साधुत्वं यथा स्यादिति ॥

(समाधानसाधकभाष्यम्)

एवं तर्ह्युभयमनेन क्रियते—पाठश्चैव विशेष्यते, कलादयश्च निवर्त्यन्ते ॥

कथं पुनरेकेन यत्नेनोभयं लभ्यम् ?

लभ्यमित्याह ।

द्विगता अपि हेतवो भवन्ति । तद्यथा—आ-

श्राद्ध सिक्ताः पितरश्च प्रीणिता इति । तथा वाक्यान्यपि श्लिष्टानि भवन्ति—श्वेतो धावति, अलम्बुसानां यातेति ॥

(प्रदीपः) **उभयमिति** । यथाभूता गर्गादिस्था अकारादयस्तथाभूता एव सर्वत्र प्रयोक्तव्या इति प्रतिपाद्यते—इत्यर्थः ॥ **द्विगता इति** । द्वौ—अर्थौ गताः—प्रयोजनद्वयस्य संपादका इत्यर्थः ॥ **तथा वाक्यान्यपीति** । शब्दस्याप्यर्थवत् द्विगतत्वमित्यर्थः ॥

(उद्द्योतः) नन्वपठितेषु दोषनिवृत्तिर्न कृता स्यादत आह—**यथाभूता इति** । गर्गाद्यकारादिषु एकरूपेण पठितेषु तज्जातीया एव ते सर्वत्र साधव इत्यनुमातुं शक्यत इति भावः ॥ भाष्ये—**पाठश्चेति** । विशेष्यते—तत्तत्प्रत्ययवैशिष्ट्येन बोध्यत इत्यर्थः ॥ **'श्लिष्टानि'** इत्यस्य द्वयोरर्थयोस्तिष्ठन्तीत्यर्थं इत्याह—**शब्दस्यापीति** । तत्र 'कः कीदृशो धावति' इति प्रश्ने—श्वेत इति उत्तरम् । 'श्वा-इतः' इति छेदेन 'कः' इत्यस्योत्तरम्, श्वेत इति च्छेदेन 'कीदृशः' इत्यस्योत्तरमिदम् ॥ एवं 'केषां जनपदानां गन्ता को वा समर्थः' इति प्रश्ने उत्तरम्—**अलमित्यादि** । अलंबुसाः—देशविशेषाः । बुसानां-पलालवर्णानां याता—प्राप्तिमान् अलं—समर्थं इति चार्थः । **'पाता'** इति क्वचित्पाठः । 'पा—रक्षणे' इत्यस्य रूपम् ॥

(सिद्धान्तभाष्यम्)

अथवा-इदं तावदयं प्रष्टव्यः—क्वेमे संवृतादयः श्रूयेरन्निति ?

आगमेषु ।
आगमाः शुद्धाः पठ्यन्ते ॥
विकारेषु तर्हि ।
विकाराः शुद्धाः पठ्यन्ते ॥
प्रत्ययेषु तर्हि ।
प्रत्ययाः शुद्धाः पठ्यन्ते ॥
धातुषु तर्हि ।
धातवोऽपि शुद्धाः पठ्यन्ते ॥
प्रातिपदिकेषु तर्हि ।
प्रातिपदिकान्यपि शुद्धानि पठ्यन्ते ॥
यानि तर्ह्यग्रहणानि प्रातिपदिकानि ।

एतेषामपि स्वरवर्णानुपूर्वीज्ञानार्थ उपदेशः कर्तव्यः । शशः षष इति मा भूत् । पलाशः पलाष इति मा भूत् । मञ्चको मञ्जक इति मा भूत् ॥

'आगमाश्च विकाराश्च प्रत्ययाः सह धातुभिः ।
उच्चार्यन्ते ततस्तेषु नेमे प्राप्ताः कलादयः ॥ १ ॥'

इति श्रीमद्भगवत्पतञ्जलिविरचिते व्याकरणमहाभाष्ये प्रथमस्याध्यायस्य प्रथमे पादे प्रथममाह्निकम् ॥

(प्रदीपः) **अथ वेति** । केवलानां वर्णानां लोके प्रयोगाभावात् धात्वादीनां च शुद्धानां पाठात् तत्स्थत्वाच्च वर्णानां न कश्चिद्दोषः ॥ **यानि तर्हीति** । डित्थादीनि ॥ **एतेषामपीति** । शिष्टप्रयुक्तत्वेनोणादीनां पृषोदरादित्वाच्च साधुत्वाभ्यनुज्ञानात्सर्वप मत्र सङ्ग्रहः सिद्धः ॥

इत्युपाध्यायजैयटपुत्रकैयटकृते महाभाष्यप्रदीपे प्रथमस्याध्यायस्य प्रथमे पादे प्रथममाह्निकम् ॥ १ ॥

(उद्द्योतः) **केवलानामिति** । एवं च कलादिदोषाणां न कुत्रापि प्रसक्तिरिति भावः ॥ भाष्ये—**यानि तर्ह्यग्रहणानीति** । कार्यविधायकसूत्रानुपात्तानीत्यर्थः ॥ **उपदेश इति** । 'ङ्याप्प्रातिपदिकात्'इत्यादावनुवादरूपेण ग्रहणमित्यर्थः । एतेन 'उद्देशश्च प्रातिपदिकानां नोपदेशः' इति 'आदेच्–' इति सूत्रस्थभाष्यविरोध इत्यपास्तम् ॥ नन्वेवमतिप्रसङ्गः स्यादत आह—**शिष्टेति** । एवं 'संवृतादीनां प्रतिषेधः'इत्यस्मिन् प्रत्याख्याते 'इष्टबुद्ध्यर्थः' इत्यपि प्रत्याख्यातप्रायमेवेत्यलम् ॥

इति शिवभट्टसुतसतीगर्भसंभवनागोजीभट्टेन कृते भाष्यप्रदीपोद्द्योते प्रथमस्य प्रथमे आद्यमाह्निकम् ॥

इति वर्णोपदेशाधिकरणम् ।

॥ इति प्रथमं पस्पशाह्निकम् ॥

अथ द्वितीयं प्रत्याहाराह्निकम् ॥

(शिवसूत्रम्)

अइउण् ॥ १ ॥

(व्यक्तिपक्षाधिकरणम्)

(२२ विवृतोपदेशप्रतिज्ञावार्तिकम् ॥ १ ॥)

॥ * ॥ अकारस्य विवृतोपदेश आकारग्रहणार्थः ॥ * ॥

(भाष्यम्)

अकारस्य विवृतोपदेशः कर्तव्यः ।
किं प्रयोजनम् ?
आकारग्रहणार्थः । अकारः सवर्णग्रहणेनाऽऽकारमपि यथा गृह्णीयात् ॥

(प्रदीपः) **अइउण्** ॥ सर्ववर्णानविशेषेण विचार्य विशेषेणात्र विचारः क्रियते—**अकारस्येति** । अत्राकारादीनां स्वरूपेणानुकार्येण वा सतोऽप्यर्थवत्त्वस्याविवक्षितत्वाद्विभक्त्यनुत्पत्तिः । स्वरसन्धिस्तु न प्रवर्तते, वर्णोपदेशकालेऽजादिसंज्ञानामनिष्पादात् । अत्राकारस्य संवृतत्वाद्दीर्घप्लुतयोर्विवृतत्वात्प्रयत्नभेदात्सवर्णसंज्ञाया अप्रसङ्गात् प्रदेशेष्वकारेण दीर्घप्लुतयोर्ग्रहणं न प्राप्नोतीति विवृतत्वमकारस्योपदिश्यते । विवृतस्य गुणस्योपदेशः—विवृतोपदेशः । तत्र गुणस्य नित्यसापेक्षत्वादकारापेक्षत्वेऽपि समासः । यथा—देवदत्तस्य गुरुकुलमिति ॥ **आकारग्रहणार्थ इति** । 'विवृतोपदेश आकारग्रहणार्थः' इति सामानाधिकरण्येन निर्देशादाकारग्रहणं विवृतोपदेशस्य प्रयोजनमिति सामर्थ्यादवगमाच्चोद्यानुरूपमुत्तरं न भवतीति न चोदनीयम् ॥ **सवर्णग्रहणेनेति** । येन शास्त्रेण **'अणुदित्सवर्णस्य–'** इत्यनेन सवर्णा गृह्यन्ते, तेन कारणेनेत्यर्थः ॥

(उद्द्योतः) ननु चतुर्दशसूत्र्याः प्रयोजनमुक्तमेव तत्किं पुनरत्र तद्ग्रहणेनेत्याशङ्क्याह—**सर्वेति** ॥ **विशेषेण**–तत्तद्रूपेण ॥ प्रत्येकं वर्णेभ्यो विभक्तिमाशङ्क्याह—**स्वरूपेणेति** । शब्दजन्यज्ञानविषयो हि शब्दस्यार्थः । एवं च स्वरूपमपि स्वजन्यबोधविषयत्वेनार्थः । अनुकार्यमर्थं इति तु स्पष्टमेव । एवं विद्यमानस्याप्यर्थवत्त्वस्याविवक्षितत्वात् **'अर्थवत्–'**सूत्रेऽग्रहणादित्यर्थः । स्वरूपस्य श्रोत्रगृहीतस्यैव शाब्दे मानोपपत्तौ न तत्र शक्तिः कल्प्या । अनुकार्यं च सादृश्येनोपस्थापयतीति न तत्रापि वृत्तिः । वृत्त्याऽर्थबोधकत्वं चार्थवत्त्वं **'अर्थवत्–'**सूत्रे निविष्टमिति भावः ॥ अनुकरणत्वभङ्गान्न विभक्तिरिति तत्त्वम्, सौत्रत्वाद्वा । कारप्रत्ययोऽपि बाहुल्कान्न ॥ **स्वरसंधिस्त्विति** । सौत्रत्वात् संहिताया अविवक्षणाद्वेति भावः ॥ **'अजादिसंज्ञानामनिष्पादात्'**इति तु चिन्त्यं, वर्णोपदेशे इत्संज्ञायामच्प्रत्याहारे च निष्पन्ने प्रवर्तमानानां यणादीनां 'सुध्युपास्यः' इत्यादौ तदस्य इत्योद्देश्यतावच्छेदकाक्रान्ते वर्णोपदेशादावपि प्रवृत्तेर्दुर्वारत्वात् । अन्यथा 'तुल्यास्यप्रयत्नं–' इत्यादौ सवर्णदीर्घादि न स्यात् ॥ **अत्र**–सूत्रे ॥ [**'तत्र'** इति पाठेऽप्ययमेवार्थः ॥] वाक्यापरिसमाप्तिन्यायेनेह ग्रहणकशास्त्राप्रवृत्तेः सावर्ण्येऽपि नात्र तद्ग्रहणमिति व्यर्थो विवृतोपदेशोऽत आह—**प्रदेशेष्विति** । **'अकः सवर्णे–'** इत्यादौ । तत्राप्यकारः संवृत एवेति भावः ॥ ननु विवृतपदस्य गुणिपरत्वे सविशेषणत्वात्समासो न स्यादत आह—**विवृतस्य गुणस्येति** ॥ भाष्ये **'कर्तव्यः'** इत्यस्य 'प्रतिषेयः' इत्यर्थः । एतेन तस्योच्चारयितुमशक्यत्वमित्यपास्तम् ॥ भाष्ये **'किं प्रयोजनम्'** इत्यत्र 'उद्दिश्य' इत्यध्याहारः, 'कर्तव्यः' इत्यनुषङ्गश्च ॥ नन्वाकारग्रहणं सवर्णग्रहणमेवेति भेदाभावात्कथं तस्य करणत्वमत आह—**येन शास्त्रेणेति** ॥

(आक्षेपभाष्यम्)

किं च कारणं न गृह्णीयात्?

(प्रदीपः) **किं च कारणमिति** । आकृतिपक्षाश्रयेण ग्रहणकशास्त्रस्य प्रत्याख्यानादाकारस्याप्यत्वजातिसद्भावात् सिद्धं ग्रहणमिति भावः । अत्र च ***निमित्तकारणहेतुषु सर्वासां प्रायदर्शनम्*** इति प्रथमा कृता । तेन 'कस्मात्कारणात्' इत्यर्थः संपद्यते ॥

(उद्द्योतः) नन्वाकृतिभेदात् कथं तत्पक्षेऽप्यकारेणाकारग्रहणमत आह—**आकारस्यापीति** । केवलकण्ठ्यत्वे सति स्वरत्वं–अत्वजातिव्यञ्जकमिति दीर्घप्लुतयोरपि सा–इति भावः ॥ प्रातिपदिकार्थमात्रे प्रथमायां यथाश्रुतेऽन्वयो न जायतेऽत आह—**अत्र चेति** ॥

(समाधानभाष्यम्)

विवारभेदात् ॥

(प्रदीपः) 'विवारभेदात्' इत्यत्र तु कारणशब्दस्य प्रयोगाभावात् प्रायग्रहणादसर्वनाम्नो वा प्रथमाद्वितीययोरभावात् 'विभाषा गुणेऽस्त्रियाम्' इति पञ्चमी विहिता ॥ विवारयति–विकासयति आस्यमिति–विवारः प्रयत्नः । व्यक्तिपक्षे ग्रहणकशास्त्रारम्भाद्दोषापत्तिः ॥

(उद्द्योतः) उत्तरेऽपि तर्हि प्रथमा कुतो नेत्यत आह–**प्रयोगाभावादिति** । निमित्तादिशब्दप्रयोगाभावेऽपि तदर्थे गम्यमाने स्यादेव विभक्तिरत आह—**प्रायग्रहणादिति** ॥ **विभाषा गुणे इति** । 'निमित्त–' इत्यादिवार्तिके 'सर्वासां' इत्येतन्न पञ्चमीतृतीयाविधायकं, किं तु 'हेतौ' इति 'विभाषागुण–' इति सिद्धयोस्तयोरन्याभिरबाधायानुवादकमेवेति भावः ॥ **विवारयतीति** । स चाभ्यन्तरप्रयत्नः ॥ **दोषापत्तिरिति** । दण्डाढकमित्यादौ दीर्घानापत्तिर्दोष इत्यर्थः ॥

(प्रत्याक्षेपभाष्यम्)

किमुच्यते—विवारभेदादिति, न पुनः कालभेदादपि । यथैव ह्ययं विवारभिन्नः, एवं कालभिन्नोऽपि?

(प्रदीपः) व्यक्तिपक्षे भेदान्तरसद्भावादाह—**किमुच्यत इति** ॥

(उद्द्योतः) ननु प्रयत्नभेदेऽपि जातिसद्भावात्स्यादेव ग्रहणमत उक्तम्—**व्यक्तिपक्ष इति** ॥

(समाधानभाष्यम्)

सत्यमेवमेतत् । वक्ष्यति–"तुल्यास्यप्रयत्नं सवर्णम्"इत्यत्रास्यग्रहणस्य प्रयोजनम्—आस्ये येषां तुल्यो देशः प्रयत्नश्च, ते सवर्णसंज्ञा भवन्तीति । बाह्यश्च पुनरास्यात्कालः । तेन स्यादेव कालभिन्नस्य ग्रहणम्, न पुनर्विवारभिन्नस्य ॥

(प्रदीपः) **बाह्यश्चेति** । प्रयत्नाभिनिर्वृत्तत्वात्कालस्य प्रयत्नत्वमभ्युपगम्य बाह्यत्वेन परिहारः । प्रसिद्धपरिमाणवस्त्वन्तरगतपरिच्छेदकक्रियान्तरापेक्षणात्कालव्यवहारस्य बाह्यत्वं कालस्य । यथा–व्रीहेः प्रस्थादिव्यवहारः परिमाणद्रव्यकृतः, एवं मात्रादिव्यपदेशो निमेषादिक्रियाकृतः ॥ अथवा नाभिप्रदेश एव विशिष्टप्रयत्नारम्भाद्दीर्घादिनिष्पत्त्या नाभेश्चास्याद्बाह्यत्वात्कालस्य बाह्यत्वम् । विवृतत्वादीनां त्वास्यवर्तिप्रयत्ननिष्पाद्यत्वादाभ्यन्तरत्वम् । द्रुतादिवृत्तयस्तु यथा न भेदिकास्तथा **तपरसूत्रे** वक्ष्यते ॥

(उद्द्योतः) ननु कालस्य व्यापकत्वात् बाह्यत्वेन समाधानमयुक्तम्, किं च कालो न प्रयत्न इति तद्भेदे कथं सवर्णत्वाप्राप्तिरत आह—**प्रयत्नाभीति** ॥ बाह्यत्वं व्युत्पादयति—**प्रसिद्धेति** । प्रसिद्धपरिमाणं यद्वस्त्वन्तरगतं परिच्छेदकक्रियान्तरं परिच्छेद्यक्रियापेक्षयाऽन्यत् तदपेक्षणादित्यर्थः । एवं च बाह्यपरिच्छेदकक्रियापेक्षया बाह्यत्वोक्तिरिति भावः । क्रियैव कालः, नातिरिक्त इति मते इदम् ॥ 'अतिरिक्तः क्षणसमूहः कालः' इति मते परिहरति—**अथ वेति** । अयं भावः–नाभिप्रदेशावच्छिन्नयत्नेन प्रेरितो वायुस्तत्स्थानाभिघातोत्तरं वर्णाभिव्यञ्जक इति शिक्षादौ स्पष्टम् । वायोरल्पत्वाधिक्यानि च ह्रस्वत्वदीर्घत्वादिरूपकालव्यञ्जकानीति ॥ ननु ह्रस्वदीर्घयोः कालभेदात् 'अतो भिस–' इत्यादौ दीर्घग्रहणवद्विलम्बितवृत्त्योच्चारितस्य ह्रस्वाकारस्यापि द्रुतमध्यापेक्षया कालाधिक्यात् ऐस्भावविधायके ग्रहणानापत्तिरत आह—**द्रुतादीति** ॥

(आक्षेपभाष्यम्)

किं पुनरिदं विवृतस्योपदिश्यमानस्य प्रयोजनमन्वाख्यायते, आहोस्वित् संवृतस्योपदिश्यमानस्

विवृतोपदेशश्चोद्यते ?

(प्रदीपः) किं पुनरिति । किं सूत्रकारेणैव विवृतोपदेशः कृतो वार्तिककारेण तु तस्य प्रयोजनमुक्तम्, अथवाऽकृत एव विवृतोपदेशो वार्तिककृता कर्तव्यत्वेनोपन्यस्त इति प्रश्नः । दुरवधारत्वादुपदिष्टो विवृतो व्याख्यानेन विना न शक्यते ज्ञातुमिति प्रत्यक्षेऽप्यकारे प्रश्नोऽयं नासमञ्जसः ।

(उद्योतः) 'उपदिश्यमानस्य' इत्यत्र वार्तिककृतः कर्तृत्वे पक्षयोर्भेदो न स्यादत आह—किं सूत्रकारेणेति । सूत्रकारः—महेश्वरः । वेदपुरुषो वा, 'येनाक्षरसमाम्नायम्' इत्याद्यैतिशादित्याहुः ॥ ननु प्रत्यक्षतोऽकारे श्रुते तद्गतगुणस्यापि ज्ञातत्वात्प्रश्नोऽयमसङ्गतोऽत आह—दुरवधारत्वादिति । विवृतत्वादीनां श्रोत्रेन्द्रियग्राह्यत्वाभावादिति भावः ॥

(समाधानभाष्यम्)

विवृतस्योपदिश्यमानस्य प्रयोजनमन्वाख्यायते ॥

कथं ज्ञायते ?

यदयम्–"अ अ"–इत्यकारस्य विवृतस्य संवृतताप्रत्यापत्तिं शास्ति ॥

(प्रदीपः) तत्र प्रत्यापत्त्या पूर्वः पक्ष आश्रितः । अन्यथा शास्त्रान्ते प्रत्यापत्तिवचनमनर्थकं स्यात्, स्वरूपप्रच्यवाभावात् ॥

(उद्योतः) अन्यथा–संवृतत्वे । स्वरूपप्रच्यवे हि पुनः संवृतविधानं युक्तं स्यादिति भावः ॥

(समाधानबाधकभाष्यम्)

नैतदस्ति ज्ञापकम् । अस्ति ह्यन्यदेतस्य वचने प्रयोजनम् ॥

किम् ?

अतिखट्वः–अतिमालः–इत्यत्रान्तर्यतो विवृतस्य विवृतः प्राप्नोति, संवृतः स्यादित्येवमर्था प्रत्यापत्तिः ॥

(प्रदीपः) अस्ति ह्यन्यदिति । प्रयोग एव प्राप्ते विवृतत्वे संवृतत्वप्रत्यापत्तिः स्यादिति–अज्ञापकमेतदित्यर्थः ॥ नन्विहासति विवृतोपदेशे सावर्ण्याभावादकारेणाकारस्याग्रहणादन्वाभावात्कथमतिखट्व इति ह्रस्वः ? नैष दोषः, 'उदीचामातः स्थाने–' इति ज्ञापकाद्भवत्याकारस्य ह्रस्वः ॥

(उद्योतः) प्रयोग एवेति । 'अतिखट्वः' इत्यादिप्रयोगे ह्रस्वेनान्तरतम्याद्विवृतोऽकारः प्राप्तः संवृत एव भवत्वित्यर्थं प्रत्यापत्तिवच इति भावः ॥ नन्विति । 'अचश्च' इत्युक्तेरच एव ह्रस्वत्वेन भाव्यमिति भावः । 'गोस्त्रियोः' इत्यत्रैतद्वारणार्थमेवोपस्थितिः स्यादिति तात्पर्यम् ॥ उदीचामात इति । न च 'आपोऽन्यतरस्याम्' इति ह्रस्वे चरितार्थमिदम् । न चात्राच्परिभाषोपतिष्ठते, फलाभावादिति वाच्यम् । शास्त्रस्याल्पविषयतापत्तेः, गोशब्दसाहचर्येण स्त्र्यंशेऽपि 'अचश्च' इत्यस्याप्रवृत्तेश्च । तदंशे हि फलाभावान्न प्रवर्तते–इति दिक् ॥

(समाधानसाधकभाष्यम्)

नैतदस्ति । नैव लोके न च वेदेऽकारो विवृतोऽस्ति ।

कस्तर्हि ?

संवृतः, योऽस्ति स भविष्यति ।

तदेतत्प्रत्यापत्तिवचनं ज्ञापकमेव भविष्यति–'विवृतस्योपदिश्यमानस्य प्रयोजनमन्वाख्यायते' इति ॥

(प्रदीपः) नैतदिति । प्रयुक्तानामनुशासनात् प्रयोगे च विवृतस्याकारस्याभावात्संवृत एव भविष्यतीति प्रत्यापत्तिर्ज्ञापिकैव ।

(आक्षेपभाष्यम्)

कः पुनरत्र विशेषः–विवृतस्योपदिश्यमानस्य प्रयोजनमन्वाख्यायेत, संवृतस्योपदिश्यमानस्य वा विवृतोपदेशश्चोद्येतेति ?

(प्रदीपः) कः पुनरिति । 'विवृतोपदेशः' इत्यत्र 'कृतः' इति वा 'कर्तव्यः'इति वा वाक्यशेषाध्याहारे न कश्चिद्विशेष इत्यर्थः ॥

(उद्योतः) नन्वाद्यपक्षे प्रयोजनान्वाख्यानमात्रपरत्वं, द्वितीये विवृतोपदेशपरत्वमपि–इति विशेषस्य स्पष्टत्वात्–अत आह—विवृतोपदेश इत्यत्रेति ॥

(समाधानभाष्यम्)

न खलु कश्चिद्विशेषः । आहोपुरुषिकामात्रं तु भवानाह—'संवृतस्योपदिश्यमानस्य विवृतोपदेशश्चोद्यते' इति । वयं तु ब्रूमः—'विवृतस्योपदिश्यमानस्य प्रयोजनमन्वाख्यायते' इति ॥

(प्रदीपः) आहोपुरुषिकेति । अहो अहं पुरुष इत्यहङ्कारवान्–अहोपुरुषः, तस्य भाव इति मनोज्ञादित्वाद्वुञ् । अहंकारवत्त्वमित्यर्थः ॥

(उद्योतः) 'आहोपुरुषिका' इत्यत्र वुञः प्राक् मयूरव्यंसकादित्वात्समासः । अहो इति–अहमित्यर्थे । अत्र प्रयोजनान्वाख्यानमित्येव न्यायः, प्रत्यापत्तेः । अकर्तृके आज्ञापादनाभावाच्चेत्याहुः ॥

(२३ धात्वादिषु विवृतत्वप्रतिज्ञावार्तिकम् ॥ २ ॥)

॥ * ॥ तस्य विवृतोपदेशादन्यत्रापि विवृतोपदेशः सवर्णग्रहणार्थः ॥ * ॥

(भाष्यम्)

तस्यैतस्याक्षरसमाम्नायिकस्य विवृतोपदेशादन्यत्रापि विवृतोपदेशः कर्तव्यः ॥

क्वान्यत्र ?

धातुप्रातिपदिकप्रत्ययनिपातस्थस्य ॥

किं प्रयोजनम् ?

सवर्णग्रहणार्थः । आक्षरसमाम्नायिकेनास्य ग्रहणं यथा स्यात् ॥

किं च कारणं न स्यात् ?

विवारभेदादेव ॥

(प्रदीपः) तस्येति । यदा प्रत्याहारे विवृतोऽकार उपदिष्टस्तदा प्रयत्नभेदात्तेन संवृतस्याकारस्य ग्रहणाभावादच्कार्य

न स्यादिति तत्सिद्धये सर्वस्याकारस्य विवृतत्वं कर्तव्यमित्यर्थः । तेन 'शाम्यति'इत्यादौ दीर्घादि सिद्ध्यति ॥ ननु च सर्वेषामकाराणां यत्सामान्यं तदनुकरणमत्राकारः । तस्य च विवृतत्वे प्रतिज्ञायमाने सर्वेषां तत्प्रतिज्ञातं भवतीति किमुच्यते—'तस्य विवृतोपदेशात्' इति ? एवं तर्हि यदा कस्यचिदेवाकारस्येदमनुकरणं-स्वरूपपदार्थको वाऽकारस्तदेदमुच्यत इत्यदोषः ॥

(उद्द्योतः) प्रत्यापत्त्या 'अइउण्' इत्यत्रैव प्रक्रियादशायां सर्वत्राकारो विवृतः प्रतिज्ञात इत्यजानन् शङ्कते—भाष्ये—तस्य विवृतोपदेशादिति । तस्येत्यस्य वर्णसमाम्नायस्थस्येत्यर्थः ॥ संवृतस्येति । धात्वादिस्थस्येत्यर्थः ॥ ननु 'अइउण्' इत्यादौ कस्यानुकरणमित्यत्र विनिगमकाभावादाह—स्वरूपपदेति । स्वरूपपदार्थकत्वं यथा तथोक्तम् ॥ भाष्ये—विचारभेदादिति । प्रयत्नभेदादित्यर्थः ॥ ग्राहकस्य विवृतत्वात् ग्राह्यस्य संवृतत्वादिति भावः ॥

(धात्वादिषु ज्ञापकेन विवृतत्वसाधकभाष्यम्)

आचार्यप्रवृत्तिर्ज्ञापयति-भवत्याक्षरसमाम्नायिकेन धात्वादिस्थस्य ग्रहणमिति । यदयम् "अकः सवर्णे दीर्घः" इति प्रत्याहारेऽको ग्रहणं करोति ।

कथं कृत्वा ज्ञापकम् ?

न हि द्वयोराक्षरसमाम्नायिकयोर्युगपत्समवस्थानमस्ति ॥

(प्रदीपः) यदयमिति । अत्र हि ककारेण चिह्नेन प्रत्याहारस्थो विवृतो निर्दिष्टः, तेन च संवृतस्याग्रहणे 'इकः सवर्णे–' इति वक्तव्यम् ॥ न हि द्वयोरिति । यद्यप्येकोऽपि विवृतो नास्ति, तथापि व्यधिष्ठानत्वादेकादेशस्य 'द्वयोः' इत्युक्तम् ॥

(उद्द्योतः) (भाष्ये) प्रत्याहारे इति । संग्राहके शास्त्र इत्यर्थः ॥ वक्तव्यमिति । एवं च प्रयत्नभेदेनासवर्णस्यापि अत्वजात्याक्रान्तस्य विवृतेनाकारेण ग्रहणं ज्ञाप्यत इत्यर्थः ॥ यद्यप्येकोऽपीति । प्रत्युच्चारणं वर्णान्यत्वादाक्षरसमाम्नायिकस्य प्रयोगेऽभावादिति भावः ॥ 'आदिरन्त्येन' इत्यस्य चान्त्यसदृशेन सहोच्चार्यमाण आदिसदृश इत्याद्यर्थः । तत्र ककारादिचिह्नेनागादिशब्दस्यस्तत्सदृशत्वाद्विवृत एव । सादृश्यं च व्यक्तिभेदे सति सर्वधर्मसाम्यप्रयुक्तं ग्राह्यम् । तस्य च प्रयोगस्येऽभावेऽप्यनेन तद्ग्रहणं ज्ञाप्यत इति तात्पर्यम् ॥ केचित्तु 'देवदत्त अजस्ति' इत्यादौ प्रत्याहारलिङ्गेनैक आक्षरसमाम्नायिकोऽस्ति, तदर्थं भाष्ये 'द्वयोः' इत्युक्तमित्याहुः ॥ भाष्ये—युगपत्समवस्थानमित्यस्य 'प्रयोगे' इत्यादिः ॥

(विवृतत्वसाधकज्ञापकविघटनभाष्यम्)

नैतदस्ति ज्ञापकम् । अस्ति ह्यन्यदेतस्य वचने प्रयोजनम् ।

किम् ?

यस्याक्षरसमाम्नायिकेन ग्रहणमस्ति, तदर्थमेतत्स्यात्–खट्वाढकं, मालाढकमिति । सति प्रयोजने न ज्ञापकं भवति । तस्माद्विवृतोपदेशः कर्तव्यः ॥

(प्रदीपः) नैतदिति । 'अक्' इत्यकारेण विवृतेन दीर्घस्य विवृतस्य ग्रहणादज्ञापकमेतदित्यर्थः ॥

(आक्षेपभाष्यम्)

क एष यत्नश्चोद्यते–विवृतोपदेशो नाम । विवृतो वोपदिश्येत, संवृतो वा । कोन्वत्र विशेषः ?

(प्रदीपः) क एष यत्न इति । धात्वादयः पठिताः, तत्राकारो विवृतः पठ्यताम्, न किंचिद्गौरवं भवति, तत्किमुच्यते—'अन्यत्रापि विवृतोपदेशः कर्तव्यः' इति प्रश्नः ॥

(समाधानभाष्यम्)

स एष सर्व एवमर्थो यत्नः—यान्येतानि प्रातिपदिकान्यग्रहणानि तेषामेतेनाभ्युपायेनोपदेशश्चोद्यते, तद्गुरु भवति । तस्माद्वक्तव्यम्—'धात्वादिस्थश्च विवृतः' इति ॥

(प्रदीपः) यानीति । प्रतिपदपाठस्याशक्यत्वात् 'तस्य विवृतोपदेशात्–' इत्यनेन सर्वस्याकारस्य विवृतोपदेशः कार्यतया चोद्यत इत्यर्थः ॥ धात्वादिस्थ इति । अग्रहणप्रातिपदिकार्थे विवृतत्वेऽवश्यचोदनीये धात्वादिस्थस्यापि संवृतस्यैव पठितस्य कार्यार्थं विवृतत्वं प्रतिज्ञेयम् । अन्यथा दोषरूपविवृतोच्चारणे प्रयत्नगौरवं स्यात् ॥

(उद्द्योतः) (भाष्ये) एवमर्थ इति । इत्थावेवंशब्दः प्रकारवति वर्तते–इति बहुव्रीहिः ॥ प्रातिपदिकानीति । धातुप्रत्यययोरप्युपलक्षणं बोध्यम् । सर्वाण्यग्रहणानि प्रातिपदिकादीनि विवृताकारयुक्तानि पठनीयानीत्यर्थः ॥ तद्गुरु भवति तस्मादिति । यतः सर्वोच्चारणं गुरु, अतो धात्वादिस्थ इति वाच्यमित्यर्थः ॥ ननु धातूनां बहुधा पाठात् 'धात्वादि–' इति अयुक्तमत आह—अग्रहणेति । प्रातिपदिकेत्युपलक्षणम् ॥ धात्वादिस्थस्यापीति । पठितधात्वादिस्थस्यापीत्यर्थः । एतेन 'अग्रहणधात्वादि' इत्येव वक्तुमुचितमित्यपास्तम् ॥ संवृतस्यैवेति । एवञ्च धात्वादिस्थश्च विवृतवत् कार्यं लभत इत्यतिदेशोऽयमिति भावः ॥ अन्यथेति । गुणोच्चारणादोषोच्चारणे यत्नाधिक्यमिति भावः ॥

(२४ एकदेशिनः प्रयोजनान्तरवार्तिकम् ॥ ३ ॥)

॥*॥दीर्घप्लुतवचने च संवृतनिवृत्त्यर्थः॥*॥

(भाष्यम्)

दीर्घप्लुतवचने च संवृतनिवृत्त्यर्थो विवृतोपदेशः कर्तव्यः, दीर्घप्लुतौ संवृतौ मा भूतामिति । वृक्षाभ्याम्, देवदत्ता ३ इति ॥

(प्रदीपः) विवृतत्वप्रतिज्ञाने प्रयोजनान्तरमाह–दीर्घेति । असति विवृतत्वप्रतिज्ञाने संवृतस्याकारस्य स्थाने सावर्ण्यात्संवृतयोरेव दीर्घप्लुतयोः प्रसङ्ग इत्यर्थः ॥

(सिद्धान्तिनो निराकरणभाष्यम्)

नैव लोके न च वेदे दीर्घप्लुतौ संवृतौ स्तः ।

कौ तर्हि ?

विवृतौ । यौ स्तस्तौ भविष्यतः ॥

(प्रदीपः) नैव लोक इति । असत्यपि सावर्ण्ये विवृताकारस्य संवृतस्य विवृतौ दीर्घप्लुतौ भविष्यतः, यदयं 'अतो दीर्घो यञि' 'अतो रोरप्लुतादप्लुते' इत्याहेति भावः ॥

(उद्द्योतः) ननु संवृतयोस्तयोरभावेऽपि संवृतस्य विवृतौ न स्यातामेव, आन्तरतम्याभावात् । न च–इको यण् इव–एच इक् इवानन्तरतमावपि भविष्यतः । सामर्थ्येन तत्र तथाऽङ्गीकारेऽपि खट्वाढकमित्यादौ चरितार्थस्य 'अकः सवर्णे' इत्यादेर्विषये तथा कल्पने मानाभावादत आह—असत्यपीति ॥ सावर्ण्ये इति । आन्तरतम्ये इत्यर्थः । एवं च 'अतो दीर्घ–' इति, 'अतो रोः–' इत्यत्राप्लुतादिति अतो विशेषणं च सामान्यापेक्षं ज्ञापकमिति भावः ॥

(एकदेशिप्रयोजनसाधकं श्लोकवार्तिकम्)

*** स्थानी प्रकल्पयेदेताव-**
नुस्वारो यथा यणम् । *

(भाष्यम्)

संवृतः स्थानी संवृतौ दीर्घप्लुतौ प्रकल्पयेत् । अनुस्वारो यथा यणम् । तद्यथा–सँय्यन्ता, सँव्वत्सरः, यँल्लोकं, तँल्लोकमिति—अनुस्वारः स्थानी यणमनुनासिकं प्रकल्पयति ॥

(उद्द्योतः) संवृतदीर्घादिवदनुनासिकयवलानामपि वेदलोकयोरसत्त्वं मन्यमान आह—भाष्ये–स्थानी प्रकल्पयेदित्यादि ॥

(निराकरणभाष्यम्)

विषम उपन्यासः । युक्तं यत्सतस्तत्र प्रक्लृप्तिर्भवति । सन्ति हि यणः सानुनासिका निरनुनासिकाश्च । दीर्घप्लुतौ पुनर्नैव लोके न च वेदे संवृतौ स्तः ।

कौ तर्हि ?

विवृतौ, यौ स्तस्तौ भविष्यतः ॥

(प्रदीपः) **सतस्तत्रेति** । अशक्यत्वाद्दीर्घप्लुतयोः संवृतयोरुच्चारणस्येत्यर्थः ।

(उद्द्योतः) तद्वत् संवृतौ दीर्घप्लुतावपि कुतो न सन्तावित्यत आह—अशक्यत्वादिति ॥ केचित्तु–शिष्टसंमतत्वात्ते सन्तः, इमौ तु न तथा इति भाव इत्याहुः ॥ सन्ति हि यण इति । भाष्ये 'यणः' इति बाहुल्याभिप्रायेण, रेफस्यानुनासिकत्वाभावादिति बोध्यम् ॥

(आक्षेपभाष्यम्)

एवमपि कुत एतत्—तुल्यस्थानौ प्रयत्नभिन्नौ भविष्यतः, न पुनस्तुल्यप्रयत्नौ स्थानभिन्नौ स्याताम्–ईकार ऊकारो वेति ?

(प्रदीपः) **एवमपीति** । असति विवृतत्वप्रतिज्ञाने संवृतस्याकारस्य संवृतावेवेकारोकारौ प्राप्नुतः, **'एवृतः संवृता अन्यत्राभवसान्नः'** इति कैश्चिदीकारोकारयोः संवृतत्वस्याभ्युपगमात् ॥

(उद्द्योतः) नन्वीकारोकारयोः कथं संवृतत्वमत आह—**एवृतः संवृता इति** । ई-ऊ-ऋत इत्यर्थः ॥ क्वचित्तु 'एवतः' इति पाठः । ईकार-ऊकार-अकारा इत्यर्थः ॥

(समाधानभाष्यम्)

वक्ष्यति–"स्थानेऽन्तरतमः" इत्यत्र 'स्थाने' इति वर्तमाने पुनः स्थानग्रहणस्य प्रयोजनम्–'यत्रानेकमान्तर्यं तत्र स्थानत एवान्तर्यं बलीयो भवति' इति ॥

(इति व्यक्तिपक्षाधिकरणम्)

(वर्णसमाम्नाये जातिपक्षाधिकरणम्)

(२५ पूर्वपक्ष्याक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ तत्रानुवृत्तिनिर्देशे सवर्णाग्रहण-
मनणत्वात् ॥ * ॥

(भाष्यम्)

तत्रानुवृत्तिनिर्देशे सवर्णानां ग्रहणं न प्राप्नोति– "अस्य च्वौ" "यस्येति च" ॥

किं कारणम् ?

अनणत्वात् । न ह्येतेऽणो येऽनुवृत्तौ ॥

के तर्हि ?

येऽक्षरसमाम्नाय उपदिश्यन्ते ॥

(प्रदीपः) **तत्रानुवृत्तिनिर्देश इति** । **'अकः सवर्णे दीर्घः'** इत्यादावयमेवाकारोऽनूद्यत इति ककारादिना चिह्नेन ज्ञायते । ततश्चाण्त्वात्तस्य ग्राहकत्वमस्तु । **'अस्य च्वौ'** इत्यादौ त्वकारस्यानण्त्वाद् ग्राहकत्वं न प्राप्नोतीत्यर्थः ॥ वृत्तिः=शास्त्रस्य लक्ष्ये प्रवृत्तिः, तदनुगतो निर्देशः–अनुवृत्तिनिर्देशः ॥

(उद्द्योतः) एवं चाद्यप्रयोजनार्थमेव सर्वत्राकारस्य विवृतत्वं प्रतिज्ञेयमिति स्थिते शङ्कते–भाष्ये–तत्रानुवृत्तीति ॥ एतद्विशेषणोपादानस्य फलमाह—अकः सवर्ण इति ॥ अनण्त्वादिति । अक्षरसमाम्नायेऽपठितत्वादाकारस्यैवानण्त्वमित्यर्थः ॥ प्रत्युच्चारणं वर्णभेदेऽपि 'अकः' इत्यादौ ककारेण चिह्नेनैतदनुकरणत्वानुमानमिति भावः ॥ तदनुगत इति । साक्षाल्लक्ष्यसंस्कारकबोधजनक इत्यर्थः ॥

(एकदेशिनो व्यक्त्येकत्वेन समाधाने भाष्यवार्तिकम्)

एकत्वादकारस्य सिद्धम् ।

एकोऽयमकारो यश्चाक्षरसमाम्नाये, यश्चानुवृत्तौ, यश्च धात्वादिस्थः ॥

(प्रदीपः) **एकत्वादकारस्येति** । एकैवाकारव्यक्तिः । उदात्तादिप्रतिभासस्तु व्यञ्जकध्वनिकृतः, खड्गतैलादर्शादिभेदे प्रतिबिम्बप्रतिभासभेदवत् । अकारस्य निदर्शनार्थत्वादिकारादीनामप्यैक्यं बोधनीयम् ॥

(उद्द्योतः) ननूदात्तादिविरुद्धधर्माध्यासाद्भेदः स्यादत आह—उदात्तादीति ॥ प्रतिबिम्बप्रतिभासभेदवदिति । भिन्नभिन्नाकारप्रतिबिम्बप्रतिभासवदित्यर्थः ॥ इकारादीनामपीति । सर्वध्वनिभिरेकस्य स्फोटस्यैव तत्तद्रूपेणाभिव्यञ्जनात् । तत्तद्रूपाभिव्यक्तिकृतश्च परस्परं भेदव्यवहारोऽपीति भावः ॥

(२६ आक्षेपवार्तिकम् ॥ २ ॥)

॥ * ॥ अनुबन्धसङ्करस्तु ॥ * ॥

(भाष्यम्)

अनुबन्धसङ्करस्तु प्राप्नोति । "कर्मण्यण्" "आतोऽनुपसर्गे कः" इति केऽपि णित्कृतं प्राप्नोति ॥

(प्रदीपः) **अनुबन्धसङ्कर इति** । एकत्वे क-अण्-टकादीनां भेदाभावाद्गोदादौ ङीबादिः प्राप्नोति ॥

(उद्द्योतः) भाष्ये—अनुबन्धसंकर इत्यस्य अनुबन्धकार्यसंकर इत्यर्थः ॥ ङीबादीति । 'टिड्ढा–' इत्यादिना । आदिना-णित्त्वप्रयुक्तवुक् । पर्यायेण कित्त्वणित्त्वप्रयुक्तकार्ययोरप्यविरोध इति भावः ॥

(२७ द्वितीयाक्षेपवार्तिकम् ॥ ३ ॥)

॥*॥एकाजनेकाज्ग्रहणेषु चानुपपत्तिः॥*॥

(भाष्यम्)

एकाजनेकाज्ग्रहणेषु चानुपपत्तिर्भवति ॥

तत्र को दोषः ?

किरिणा–गिरिणा–इत्येकाज्लक्षणमन्तोदात्तत्वं प्राप्नोति ।

इह च घटेन तरति–घटिक इति, द्व्यज्लक्षणष्ठन् न प्राप्नोति ॥

(प्रदीपः) किरिणेति । न गोश्वन्त्साववर्ण–इति प्रतिषेधादकारो नोदाहृतः ॥ घटेनेति । एक एवाकारो द्विरुच्चार्यत इति द्व्यच्त्वाभावः । ठंस्तु बाहुकादिषु कृतार्थः ॥

(उद्द्योतः) भाष्ये–अनुपपत्तिरिति । इष्टव्यवस्थाया इति भावः । अव्याप्त्यतिव्याप्त्योः प्रसङ्गादिति तात्पर्यम् ॥ प्रतिषेधादिति । 'सावेकाचः' इति प्राप्तस्येत्यर्थः ॥ ठंस्त्विति । 'नौद्व्यचष्ठन्' इति विहितः ॥

(२८ तृतीयाक्षेपवार्तिकम् ॥ ४ ॥)

॥ * ॥ द्रव्यवच्चोपचाराः ॥ * ॥

(भाष्यम्)

द्रव्यवच्चोपचाराः प्राप्नुवन्ति । तद्यथा—द्रव्येषु नैकेन घटेनानेको युगपत्कार्यं करोति, एवमिममकारं नानेको युगपदुच्चारयेत् ॥

(प्रदीपः) द्रव्यवदिति । उपचारः–व्यवहारः । यथैकेन घटेनोदकाहरणादिक्रियां युगपदनेको न करोति, तथैकमकारं युगपदनेको नोच्चारयेदित्यर्थः ॥

(प्रथमाक्षेपनिराकरणे भाष्यवार्तिकम् ॥)

विषयेण तु नानालिङ्गकरणात्सिद्धम् ।

यदयं विषये विषये नानालिङ्गमकारं करोति—"कर्मण्यण्" "आतोऽनुपसर्गे कः" इति, तेन ज्ञायते—नानुबन्धसङ्करोऽस्तीति । यदि हि स्यात्, नानालिङ्गकरणमनर्थकं स्यात्; एकमेवायं सर्वगुणमुच्चारयेत् ॥

(प्रदीपः) विषयेणेति । वार्तिककारेण करणत्वेन सामान्यरूपतया चाभेदेन विषयो निर्दिष्टः । भाष्यकारस्त्वधिकरणत्वं व्यक्तिभेदाद्वीप्सां च प्रतिपादयति—विषये विषय इति । सर्वगुणमिति । गुणाः=अनुबन्धाः, कार्याश्रितत्वादुपकारकत्वात् । तत्र 'कर्मणि कण्ट्' इति ब्रूयादित्यर्थः ॥

(उद्द्योतः) करणत्वेनेति । अधिकरणस्य करणत्वविवक्षयेत्यर्थः ॥ सामान्यरूपतयेति । विषयस्वरूपेणेत्यर्थः ॥ भाष्यकारस्त्विति । एकविषये नानालिङ्गकरणादर्शनाद्विषयभेदेन तदित्यत्र तात्पर्यम् ॥ 'गुणा उदात्तादयः' इति भ्रमं व्यावर्तयति—गुणा अनुबन्धा इति ॥ तेषां गुणत्वमुपपादयति—कार्येति ॥

(ज्ञापकनिराकरणभाष्यम्)

नैतदस्ति ज्ञापकम् । इत्संज्ञाप्रक्लृप्त्यर्थमेतत्स्यात् । न ह्ययमनुबन्धैः शल्यकवच्छक्य उपचेतुम् । इत्संज्ञायां हि दोषः स्यात् । आद्यस्य हि द्वयोरित्संज्ञा स्यात् ।

कयोः ?

आद्यन्तयोः ॥

(प्रदीपः) शल्यकवदिति । शल्यकः=प्राणिविशेषः । स यथा कण्टकतुल्यैः पक्षैर्व्याप्यते । नैवं सर्वानुबन्धयुक्तोऽकारः शक्यो निर्देष्टुम्, आद्यन्तयोरेवेत्संज्ञाविधानान्मध्यपातिनां श्रवणप्रसङ्गात् । इत्संज्ञैवायच्छतेर्=व्याप्रियत इत्येककर्तृकत्वात् 'आद्यस्य' इत्युक्तम् ॥

(उद्द्योतः) व्याप्रियेति । विषयत्वेन गृह्णातीत्यर्थः ॥ एककर्तृकत्वादिति । 'स्यात्' इत्यनेनेत्संज्ञारूपैककर्तृकत्वादित्यर्थः ॥

(न्यासान्तरेण व्याख्याभाष्यम्)

एवं तर्हि—

* विषयेण तु पुनर्लिङ्गकरणात्सिद्धम् * ।

यदयं विषये विषये पुनर्लिङ्गमकारं करोति—"प्राग्दीव्यतोऽण्" "शिवादिभ्योऽण्" इति, तेन ज्ञायते–नानुबन्धसङ्करोऽस्तीति । यदि हि स्यात्पुनर्लिङ्गकरणमनर्थकं स्यात् ॥

(प्रदीपः) एवं तर्हीति । 'विषयेण–' इत्येतदन्यथा व्याचष्टे–'नाना'शब्दमपनीय 'पुनः'शब्दं पठित्वा । यद्यनुबन्धसंकरः स्यादकारमेव शिवादिभ्यो विदध्यात् ॥ अथोच्येत—णित्कृतमेव यथा स्यात् यित्कृतं मा भूदिति नियमार्थमेतत् स्यात् । तन्न, नियमाद्विधेर्बलीयस्त्वात् ॥

(उद्द्योतः) 'नाना' इति स्थिते कथमन्यथा व्याख्यानमत आह—नानाशब्दमिति ॥ नियमादिति । ज्ञापकत्वे हि विध्यर्थत्वमिति भावः ॥ [अत्र वाक्यत्रयेऽपि 'तु'शब्दः पूर्वपक्षव्यावृत्तौ ॥]

(प्रथमव्याख्याभ्युपगमभाष्यम्)

अथवा पुनरस्तु—

*विषयेण तु नानालिङ्गकरणात्सिद्धम् * इत्येव ॥

(ज्ञापकनिराकरणखण्डनभाष्यम्)

ननु चोक्तम्—इत्संज्ञाप्रक्लृप्त्यर्थमेतत् स्यात्–इति ॥

(ज्ञापकसाधकभाष्यम्)

नैष दोषः, लोकत एतत्सिद्धम् । तद्यथा–लोके कश्चिदेवं देवदत्तमाह–इह मुण्डो भव, इह जटिलो भव, इह शिखी भव–इति यल्लिङ्गो यत्रोच्यते तल्लिङ्गस्तत्रोपतिष्ठते ।

एवमयमकारो यल्लिङ्गो यत्रोच्यते तल्लिङ्गस्तत्रोपस्थास्यते ॥

(प्रदीपः) अथवेति । न ब्रूमः–सर्वगुणमुच्चारयेदिति, किं तु यथा लोके–इह मुण्डो भव–इह नग्नो भव–इति मुण्डको

यत्रोच्यते तद्गुण एव तत्र भवति, एवमिहापि याभ्यः प्रकृतिभ्यो यदनुबन्धविशिष्टो विधीयते तदनुबन्धनिमित्तमेव कार्यं संपादयति ॥

(उद्द्योतः) यथा लोके इति । प्रश्वाशया गूढचारादिरिति शेषः ॥ एवंच लोकव्यवहारदृष्टान्तेनैवासंकरः सिद्ध इत्यर्थः ॥ यत्र–देशे, काले वा ॥ तद्गुण एवेति । भाष्येऽपि–'तल्लिङ्गस्तत्र' इति सावधारणं व्याख्येयमिति भावः ॥

(द्वितीयाक्षेपानुवादभाष्यम्)

यदप्युच्यते–*एकाजनेकाज्ग्रहणेषु चानुपपत्तिः* इति ॥

(२९ द्वितीयाक्षेपनिराकरणवार्तिकम् ॥ ५ ॥)

॥ * ॥ एकाजनेकाज्ग्रहणेषु चावृत्तिसंख्यानात् ॥ * ॥

(भाष्यम्)

एकाजनेकाज्ग्रहणेषु चावृत्तेः संख्यानादनेकाच्त्वं भविष्यति । तद्यथा–"सप्तदश सामिधेन्यो भवन्ति" इति "त्रिः प्रथमामन्वाह त्रिरुत्तमाम्" इत्यावृत्तितः सप्तदशत्वं भवति ।

एवमिहाप्यावृत्तितोऽनेकाच्त्वं भविष्यति ॥

(प्रदीपः) आवृत्तिसंख्यानादिति । यथा विकृतियागे त्रयोदश सामिधेन्यः प्रथमोत्तमयोस्त्रिरावृत्त्या सप्तदश संपद्यन्ते, तथा घटेन तरतीति घ्यज्लक्षणष्ठन् भवति ॥ ननु मुख्ये विषये कृतार्थत्वाद्वचनस्य गौणं घ्यच्त्वं कथं कार्यस्य निमित्तम् ? उच्यते–'गोश्च–' इत्यत्राश्वशब्दप्रतिषेधाल्लिङ्गादावृत्तिभेदेनापि भेदाश्रयकार्यप्रवृत्तिः ॥

(उद्द्योतः) यथा विकृतियागे इति । तत्र हि प्राप्तसामिधेन्यनुवादेन सप्तदशत्वं विहितम् । तच्च 'त्रिः प्रथमां–' इत्यादिवाक्यबोधितया प्रथमोत्तमयोस्त्रिरावृत्त्यैवेति भावः ॥ त्रिरावृत्त्येति । आवृत्तिः–पुनरुच्चारणम् । तज्जन्यसङ्ख्यया सप्तदशत्ववदत्रानेकाच्त्वमिति भावः ॥ भाष्ये–आवृत्तेः संख्यानात्–गणनादित्यर्थः । [लिङ्गादिति । अनेन लिङ्गेन श्रुतिस्मृतिसिद्धत्वादस्य व्यवहारस्य गौणत्वमेव नेति ज्ञाप्यत इति भावः ॥]

(आक्षेपभाष्यम्)

भवेदावृत्तितः कार्यं परिहृतम् । इह तु खलु–'किरिणा' 'गिरिणा' इत्येकाज्लक्षणमन्तोदात्तत्वं प्राप्नोत्येव ॥

(प्रदीपः) भवेदिति । 'गिरिणा' इत्यादावावृत्तिभेदेऽपि मुख्यमेकाच्त्वं न निवर्तत इति भावः ॥

(उद्द्योतः) (भाष्ये) भवेदावृत्तितः कार्यं परिहृतमिति । आवृत्त्या कार्यं सिद्धमिति कृत्वा दूषणं परिहृतं भवेदित्यन्वयः ॥ मुख्यमिति । आवृत्तिकृतद्व्यच्त्वेन स्वगतैकाच्त्वस्य बाधायोग इति भावः ॥

(समाधानभाष्यम्)

एतदपि सिद्धम् ।

कथम् ?

लोकतः । तद्यथा–ऋषिसहस्रमेकां कपिलामेकैकशः सहस्रकृत्वो दत्त्वा तया सर्वे ते सहस्रदक्षिणाः संपन्नाः ।

एवमिहाप्यनेकाच्त्वं भविष्यति ॥

(प्रदीपः) एतदपीति । लोके पूर्वा संख्या संख्यान्तरेण मुख्येन गौणेन च बाध्यत इत्यर्थः ॥ ऋषिसहस्रमिति । वित्तेन क्रीत्वा क्रीत्वा प्रत्येकं दत्त्वा दत्त्वा सहस्रदक्षिणा ऋषयः संपन्ना इत्यर्थः । सहस्रमृषयः–ऋषिसहस्रमिति कर्मधारये 'संपन्नाः' इत्यस्य साक्षादृषिभिः संबन्धः । षष्ठीसमासे तु सामर्थ्यलक्षणः संबन्धः, यथा–ब्राह्मणशतं भोज्यतामिति भुजेर्ब्राह्मणैः सह ॥

(उद्द्योतः) ननु स्वस्य प्रतिगृहीतत्वाभावादेकन्यूनता; न च पुनर्दानं, दत्तस्यान्यस्वत्वाक्रान्तत्वया पुनर्दानासंभवोऽत आह–वित्तेनेति ॥ ननु षष्ठीसमासे सहस्रसंख्याया विशेष्यत्वात्कथं दानेन संबन्धः, कथं वा 'संपन्नाः' इति बहुवचनान्तेन सामानाधिकरण्यमत आह–सहस्रमृषय इति । अत एव 'सर्वे ते' इत्यनेन सामानाधिकरण्यम् । परनिपातो भाष्यप्रामाण्यात् ॥ [भाष्ये–] 'एकैकशः' इत्यत्र उभयोरपि द्योतकत्वेन द्योतकसमुच्चयस्य च बहुशो दृष्टत्वेन द्विर्वचनशसोर्योगपद्यम् । यथा–यथाजातीयको गार्ग्यायणीत्यादौ । तत्र च यथा ष्फसत्वे समुच्चित्यद्योतकता, अभावे गार्गीति ङीपैव, तथा प्रकृतेऽपि शसो वैकल्पिकत्वात्पक्षे–एकैकमित्यपि । द्व्यादिशब्दे विषये तु न समुच्चित्य द्योतकता, अनभिधानात् । एकशब्दे तु समुच्चित्य प्रत्येकं च द्योतकता, अभिधानस्वभावात् । यत्र तद्धितेनानुक्ता वीप्सा तत्र द्विर्वचनं भवत्येव, यथा–एकैकशो देहीति । भाष्यस्याप्ययमाशयः–यत्र तद्धितमात्रेण लोके वीप्साऽनभिधानं तत्र द्विर्वचनमपि । माषश इत्यादौ तावतैव सर्वत्र वीप्साऽभिधानं तत्र न कदापि तयोः समुच्चय इति दिक् ॥ सामर्थ्यलक्षण इति । सामर्थ्यकृतो गुणभूतैरृषिभिः संबन्ध इत्यर्थः । 'सर्वे ते' इत्यत्र तच्छब्देन गुणभूतस्यापि परामर्शोऽत्र पक्षे बोध्यः । अत एव 'दत्त्वा' इति समानकर्तृके क्त्वा ॥ सहस्रं दक्षिणा गोरूपा येषां दातॄणां ते इत्यर्थः ॥ तेन गोसहस्रदानफला एव ते, न त्वेकगोदानमात्रफला इति व्यवहारो यथा स्मृतौ तथा प्रकृतेऽपीति भावः ॥ भुजेर्ब्राह्मणैरिति । सक्षयायां भोक्तृत्वानुपपत्तेर्गुणभूतब्राह्मणैरेव भुजेः संबन्ध इति भावः ॥ भाष्ये–अनेकाच्त्वमिति । तन्मात्रमित्यर्थः ॥

(तृतीयाक्षेपनिराकरणभाष्यम्)

यदप्युच्यते–द्रव्यवच्चोपचाराः प्राप्नुवन्ति । भवेद्यदसंभवि कार्यं तत्रानेको युगपत्कुर्यात् । यत्तु खलु संभवि कार्यमनेकोऽपि तद्युगपत्करोति । तद्यथा–घटस्य दर्शनं स्पर्शनं च ।

संभवि चेदं कार्यमकारस्योच्चारणं नाम, अनेकोऽपि तद्युगपत्करिष्यति ॥

(प्रदीपः) संभवि चेति । एकस्यैवाकारस्य युगपत् स्थानकरणनिष्पन्नध्वनिव्यङ्ग्यत्वात्सर्वैरित्यर्थः ॥

(उद्द्योतः) एकस्यैवेति । व्यापकस्येत्यपि बोध्यम् । अकारस्येत्यप्युपलक्षणमित्युक्तम् । भाष्ये–'उच्चारणं नाम' इत्युत्तरं 'अतः' इति शेषः ॥

(३० पूर्वपक्षिसंमतनानात्वसाधकवार्तिकम् ॥ ६ ॥)

॥ * ॥ आन्यभाव्यं तु कालशब्दव्यवायात् ॥ * ॥

(भाष्यम्)

आन्यभाव्यं त्वकारस्य ॥

कुतः ?

कालशब्दव्यवायात् । कालव्यवायाच्छब्दव्यवायाच्च ।

कालव्यवायात्-दण्ड अग्रम् ।

शब्दव्यवायात्—दण्डः ।

न चैकस्यात्मनो व्यवायेन भवितव्यम् । भवति चेत् भवत्यान्यभाव्यमकारस्य ॥

(प्रदीपः) एवं परिहृतेष्वपि तत्र दोषेषु न्यायेनाकारस्य भेदं साधयति—आन्यभाव्यमिति । अन्यस्य भावः–अन्यभावः, ततो ब्राह्मणादिषु स्वार्थे विधानार्थं पाठात् स्वार्थे ष्यञ् । अथवा–अन्यो भावः–अन्यद्वस्तु, तस्य भाव इति भावे ष्यञ् । इह कालशब्दाभ्यां व्यवधानं भिन्नानां दृष्टम् । यथाऽसंहितायाम्–अ इ उ इत्यादीनां कालव्यवायः । दतिरित्यादौ शब्दव्यवायः, तत्र तकारेण ऋकारेकारयोर्व्यवधानात् । एकत्वे तु व्यवायो न दृष्टः, यथा–अ इति केवलोऽकार उच्चार्यते । तस्मादुदात्तादिगुणभेदात्कालशब्दव्यवायाच्च नानात्वमकारस्य । प्रत्यभिज्ञानं त्वत्वादिसामान्यनिबन्धनम् । यद्यपि शब्दव्यवायेऽपि कालव्यवायोऽस्ति, तथापि कालव्यवाय एव द्विधा दर्शितः–शब्दशून्यः शब्दवांश्च ॥

(उद्द्योतः) 'आन्यभाव्यं' इत्यस्यान्यत्वमित्यर्थो नेत्याह–अन्यस्येति ॥ अथवेति । भावशब्दः कर्तृसाधन इति भावः ॥ एवंच प्रतिप्रयोगमकारस्यान्यत्वमित्यर्थः ॥ यथेति । एवञ्च–अग्रे इत्याद्यकारो दण्डेत्यकाराद्भिन्नः, 'दण्ड अग्रं' इत्यादौ कालव्यवधानात्, 'दण्ड इह' इति प्रयोगे इकारवत् । तथा 'दण्ड' इत्यत्राद्याकारोऽन्त्याकाराद्भिन्नः, शब्दव्यवायात्, कृतिरित्यादौ तकारव्यवहितेकारवत्–इत्यनुमानैर्भेदे सिद्धे उदात्तादिविरुद्धधर्मप्रत्ययोऽपि पारमार्थिक एवेत्याशयेन तद्भेदादपि भेदसिद्धिरित्यभिप्रेत्याह—उदात्तादीति ॥ नानात्वमकारस्येति । 'युक्तं' इति शेषः ॥ ननु य एवोदात्तोकारः स एव देवदत्तेनानुदात्तः कृत इति प्रत्यभिज्ञाविरोधोऽत आह—प्रत्यभिज्ञानं त्वेति ॥

(३१ नानात्वहेतुवार्तिकम् ॥ ७ ॥)

॥ * ॥ युगपच्च देशपृथक्त्वदर्शनात् ॥ * ॥

(भाष्यम्)

युगपच्च देशपृथक्त्वदर्शनान्मन्यामहे—आन्यभाव्यमकारस्येति । यदयं युगपच्च देशपृथक्त्वेषूपलभ्यते—अश्वः, अर्कः, अर्थ इति । न ह्येको देवदत्तो युगपत्स्रुघ्ने च भवति मधुरायां च ॥

(उद्द्योतः) विभुत्वं निराचष्टे भाष्ये–युगपच्च देशेति । अर्कादिशब्दा एव देशपदेनोच्यन्ते ॥ देशपृथक्त्वेष्विति । देशानां पृथक्त्वेषु भेदेषु सत्स्वित्यर्थः ॥

(एकत्वसाधकभाष्यम्)

यदि पुनरिमे वर्णाः—

शकुनिवत्स्युः ।

तद्यथा—शकुनय आशुगामित्वात्पुरस्तादुत्पतिताः पश्चाद्दृश्यन्ते, एवमकारो 'द' इत्यत्र दृष्टः 'ण्ड' इत्यत्र दृश्यते ॥

(प्रदीपः) यदि पुनरिति । कालशब्दाभ्यां व्यञ्जकानामेव ध्वनीनां व्यवायः, न व्यङ्ग्यस्येति व्यक्तिस्फोटवादिनो भावः ॥ यथा शकुनिः पङ्क्तेरादौ स्थित आशुसंचारात्तदन्ते भवति, एवं व्यञ्जकध्वनिसंनिधानासन्निधानाभ्यामकारस्योपलम्भानुपलम्भावित्यर्थः ॥

(उद्द्योतः) एवं वर्णानामनेकत्वे परेण साधिते वर्णैकत्ववादी एकत्वं स्थापयितुं तद्दूषणोद्धारमाह–भाष्ये–यदि पुनरिति ॥ तत्र 'शकुनिवत्' इति दृष्टान्तस्य तद्वत्परिच्छिन्नत्वे न तात्पर्यम्, तन्मते तस्य विभुत्वादिति ध्वनयन्नाह—कालशब्दाभ्यामिति ॥ व्यक्तिस्फोटवादिन इति । व्यक्तेर्नित्यत्वैकत्ववादिनः, एकैव शब्दव्यक्तिरिति वादिन इत्यर्थः । अनेनाद्यं दूषणं परिहृतम् ॥ द्वितीयं परिहरति—यथेति ॥ एवमिति । अस्यानेकदेशेषु युगपदुपलम्भो व्यञ्जकवशादिति शेषः । पूर्वदृष्टस्य पश्चाद्दर्शनेऽपि–अव्यवहितस्य व्यवधानेऽपि न भेद इत्येतन्मात्रेण दृष्टान्त इति भावः ॥ नन्वेवं विभुत्वे च सर्वत्र देशे सर्वदोपलम्भापत्तिरत आह—व्यञ्जकेत्यादि ॥

(नानात्ववादिभाष्यम्)

नैवं शक्यम् । अनित्यत्वमेवं स्यात् । नित्याश्च शब्दाः । नित्येषु च शब्देषु कूटस्थैरविचालिभिर्वर्णैर्भवितव्यमनपायोपजनविकारिभिः । यदि चायं 'द' इत्यत्र दृष्टः 'ण्ड' इत्यत्र दृश्येत, नायं कूटस्थः स्यात् ॥

(प्रदीपः) जातिस्फोटवादी व्यक्तिस्फोटवादिनं पर्यनुयुङ्क्ते–अनित्यत्वमिति । भवता जातिस्तावन्नाभ्युपगम्यते, व्यक्तेरेवैकत्वनित्यत्वप्रतिज्ञानात् । तच्चैकत्वं नित्यत्वं च नोपपद्यते, 'दण्ड' इत्युदात्तानुदात्तस्वरभेदेन भिन्नत्वात् । न ह्येकस्यैवोदात्तत्वपरित्यागेनानुदात्तत्वं युक्तम्, रूपान्तरपरिग्रहादनित्यत्वप्रसङ्गः । तस्माद्भिन्ना एवानित्या एवाकाराः, प्रत्यभिज्ञा त्वाकृतिनिबन्धनेति जातिस्फोटपक्षोऽत्र स्थितः ॥

(उद्द्योतः) जातिस्फोटेति । जातिरेव एका, शब्दव्यक्तयस्त्वनन्ता इति वादीत्यर्थः ॥ भाष्ये–अनित्यत्वमेवं स्यादिति । व्यक्तेरेकत्ववादी तस्या नित्यत्वं मन्यते–इति भावः ॥ ननु विभोरेकस्यापि व्यञ्जकवशादनेकत्रोपलब्धौ कथमनित्यतेत्यत आह–भवतेति ॥ भाष्येऽपि 'नित्याश्च शब्दाः' इत्यस्य 'तव' इत्यादिः ॥ भाष्योक्तकूटस्थत्वाभावमुपपादयति–रूपान्तरेति ॥ 'तस्माद्भिन्ना एवानित्या एवाकाराः' इति पाठः । 'नित्या एव' इति पाठस्त्वयुक्तः,

अनन्तवर्णवादे तदनित्यत्वस्यैवेष्टत्वादिति बोध्यम् ॥ यद्यप्यनुदात्तत्वादीनां ध्वनिनिष्ठत्वाङ्गीकारान्न दोषस्तथापि स्फटिकस्येवास्यापि इतरसंनिधानेन तद्रूपपरिग्रहे संसर्गानित्यताविरोधिकूटस्थत्वाभाव इति भावः ॥

(एकत्वसाधकभाष्यम्)

यदि पुनरिमे वर्णाः—

आदित्यवत्स्युः

तद्यथा–एक आदित्योऽनेकाधिकरणस्थो युगपद्देशपृथक्त्वेषूपलभ्यते ॥

(उद्योतः) पुनरप्येकत्वनित्यत्वे साधयति—भाष्ये–**यदि पुनरित्यादिना** । एकस्यैवाकारस्यानेकदेशेषूपलब्धिरादित्यस्येव संभवतीति न तावद्व्यक्तिभेदः सिध्यति । अन्यथा–आदित्यस्याप्यनेकत्वापत्तिरनित्यत्वापत्तिश्च । तत्तद्देशसंसर्गेणाल्पप्रकाशत्वाधिकप्रकाशत्वादिगुणसंसर्गादिति भावः ॥

(नानात्ववादिभाष्यम्)

विषम उपन्यासः । नैको द्रष्टा आदित्यमनेकाधिकरणस्थं युगपद्देशपृथक्त्वेषूपलभते । अकारं पुनरुपलभते ॥

(उद्योतः) **विषम इति** । आदित्यदृष्टान्तेनानेकदेशोपलभ्यमानाकाराद्विपक्षैक्यसाधकः प्रत्यभिज्ञायमानत्वहेतुरनेकद्रष्टृकानेकदेशोपलब्धिविषयत्वरूपोपाधियुक्त इति न तेन भेदसाधकशब्दव्यवायहेतोः सत्प्रतिपक्षता युक्तेति भावः ॥ 'अकारं पुनरुपलभते' इत्यस्यैको द्रष्टाऽनेकाधिकरणस्थमिति शेषः ॥

(एकत्ववादिभाष्यम्)

अकारमपि नोपलभते ।

किं कारणम् ?

श्रोत्रोपलब्धिर्बुद्धिनिर्ग्राह्यः प्रयोगेणाभिज्वलित आकाशदेशः शब्दः । एकं च पुनराकाशम् ॥

(प्रदीपः) व्यक्तिस्फोटवाद्याह—**अकारमपीति** ॥ **श्रोत्रोपलब्धिरिति** । श्रोत्रोपलब्ध्याऽऽकाशदेशत्वं शब्दस्य प्रतिपादयति । आकाशप्रदेशविशेषस्य श्रोत्रत्वात् इन्द्रियाणामसंबद्धविषयाग्रहणात् श्रोत्रस्य च निःक्रियत्वाद्गमनाभावादाकाशदेशत्वमस्याभ्युपेयम् ॥ **बुद्धिनिर्ग्राह्य इति** । पूर्वपूर्वध्वन्युत्पादिताभिव्यक्तिजनितसंस्कारपरम्पराप्राप्तपरिपाकान्त्यबुद्धिनिर्ग्राह्य इत्यर्थः ॥ **प्रयोगेणेति** । प्रयुज्यत इति–प्रयोगः=ध्वनिः, तेनाभिव्यक्तः ॥ देशभेदेन तु प्रतिभासो भिन्नदेशावस्थितपुरुषोदीरिताभिव्यञ्जकध्वनिकृतः ॥

(उद्योतः) शब्दस्याकाशस्यैकाधिकरणत्वेनानेकाधिकरणत्वमयुक्तमित्याशयेनाह–भाष्ये—**अकारमपि नोपलभत इति** । अकारमप्यनेकाधिकरणस्थं नोपलभत इत्यर्थः ॥ **श्रोत्रोपलब्धिरिति** । श्रोत्र एव उपलब्धिर्यस्येत्यर्थः, करणक्तिबन्तेन समानाधिकरणबहुव्रीहिर्वा ॥ एतद्विशेषणफलं दर्शयति—**श्रोत्रेति** । ननु दिश एव श्रोत्रत्वात् कथं तत्रोपलब्ध्याऽऽकाशदेशत्वसिद्धिरत आह—**आकाशेति** । कर्णशष्कुल्यवच्छिन्नं नभ एव श्रोत्रम् । चक्षुरादिवच्छ्रोत्रस्यापि भूतत्वमावश्यकमिति भावः ॥ दिशोऽनतिरिक्तमेव चाकाशमिति तत्त्वम् ॥ ननु तथाप्यतेजोंऽशगतघटादिरूपस्य तैजसचक्षुर्ग्राह्यत्ववदनाकाशदेशगतस्यापि शब्दस्याकाशात्मकश्रोत्रग्राह्यत्वं किं न स्यादित्याशङ्क्य किमसंबद्धं तद्ग्राहकं–संबद्धं वा, नाद्य इत्याह—**असंबद्धेति** । अन्यथा रामेश्वरादिप्रदेशावच्छिन्नशब्दस्यापि श्रवणप्रसङ्गः ॥ द्वितीयेऽपि किं श्रोत्रस्य विषयदेशगमनात्संबन्धः–उत शब्दस्य श्रोत्रदेशगमनात्, नोभयमपीत्याह—**गमनाभावादिति** ॥ **श्रोत्रस्य चेति**–चेन शब्दपरिग्रहः । उभयोरपि गमनाभावे हेतुः–निष्क्रियत्वं, दूरदेशस्थशब्दाग्रहणं तु दूरत्वादेर्दोषस्य प्रतिबन्धकत्वाच्छ्रोत्रदेशेऽनभिव्यक्तेः । आकाशदेशत्वे च तद्वदेव तस्यापि व्यापकत्वेन श्रोत्रदेशेऽभिव्यक्तस्य तेन ग्रह इति भावः ॥ 'आहंकारिकाणीन्द्रियाणि' इति सांख्यमतेऽपि इन्द्रियाणां स्वाधिष्ठानभूतवृत्तिगुणग्राहकत्वनियमादाकाशदेशत्वं श्रोत्रोपलब्ध्या शब्दस्य सिध्यतीति बोध्यम् ॥ श्रोत्रोपलब्धिरित्येव बुद्धिनिर्ग्राह्यत्वस्योक्तत्वात्पौनरुक्त्यमाशङ्क्याह—**पूर्वपूर्वेति** । एवं चाशुतिरोधीयमानानेकवर्णवद्घटकलशादिशब्दग्रहणसंभवदर्शनाय तदुक्तमिति न पौनरुक्त्यम् ॥ **प्राप्तपरिपाकेति** । तत्सहकृतेत्यर्थः । **अन्त्यबुद्धिः**—अन्त्यवर्णबुद्धिः । एवं च तादृशसंस्कारविशिष्टान्तःकरणसंयुक्तेन तादृशसंस्कारविशिष्टेन श्रोत्रेणान्त्यवर्णसंबद्धेन वर्णसमुदायप्रतिबिम्बवदखण्डस्फोटरूपपदादिप्रत्यक्षमिति भावः ॥ नन्वेवं सर्वदा शब्दोपलम्भः स्यादतः–भाष्ये—**प्रयोगेणाभिज्वलित इति** । तद्व्याचष्टे—**प्रयुज्यत इति** ॥ **ध्वनिरिति** । वर्ण इत्यर्थः ॥ भाष्ये—**एकं च पुनराकाशमिति** । एवं चैकस्मिन्नाम्रफले एक एव यथा रूपरसगन्धादिस्तथा तदाश्रयस्यैकत्वात्तद्गतः शब्दोऽप्येक एव । तत्रैव च तस्योपलम्भ इति भिन्नदेशोपलम्भ एवासिद्ध इति भावः ॥ नन्वेकत्वे 'अयं पूर्वः–अयं परः' 'अयं देवगृहे–अयं राजगृहे' इति भेदप्रतिभासः कथमत आह—**देशभेदेन त्विति** । औपाधिको भेदस्तु आकाशस्येव न शब्दस्याप्येकत्वे बाधकः । एवं संसर्गानित्यताऽपि तस्येव नास्यापि बाधिका, तस्यापि नीलं नभ इत्यादि संसर्गानित्यताप्रतीतेरित्याशयः ॥ अत्र 'शब्दः' इत्येकवचनेन स्फोटस्यैकत्वमखण्डत्वं च ध्वनितम् ॥

(नानात्ववादिभाष्यम्)

आकाशदेशा अपि बहवः । यावता बहवः, तस्माद्व्यभाव्यमकारस्य ॥

(प्रदीपः) भेदवाद्याह—**आकाशदेशा इति** । यथा पृथिव्या एकत्वेऽपि स्रुघ्नमथुरादिदेशभेदव्यवहारः, एवमाकाशस्यापि संयोगिघटादिपदार्थावच्छेदेन भेदव्यवहार इत्यर्थः ॥

(उद्योतः) ननु निरवयवस्य कथं प्रदेशबाहुल्यमत आह—**यथेति** । एवं चौपाधिकभेदेन भेदो दुर्वारः । सर्वत्र भेद औपाधिक एव, स एव च व्यवहारोपयोगीत्याशयः । श्रोत्रसंबन्धस्तु प्रदेशान्तरोत्पन्नशब्दस्यापि वीचीतरङ्गन्यायेन कदम्बमुकुलन्यायेन वा तत्रान्तरे व्युत्पादित एव ॥

(सिद्धान्तसमाधानभाष्यम्)

आकृतिग्रहणात्सिद्धम्

अवर्णाकृतिरुपदिष्टा सर्वमवर्णकुलं ग्रहीष्यति । तथेवर्णाकृतिः, तथोवर्णाकृतिः ॥

(प्रदीपः) एवं व्यक्तिस्फोटपक्षे निराकृते जातिस्फोटपक्षमेवाश्रयते—**आकृतिग्रहणादिति** । आकारजातिः सर्वप्रदेशेषु निर्दिश्यते । नान्तरीयकस्तु व्यक्तिनिर्देशः । तत्र प्रत्याहारेऽकारजातेर्निर्देशात्तस्याश्च विवृतत्वप्रतिज्ञानाच्छास्त्रान्ते च तस्या एव प्रत्यापत्तिविधानम् । तदेवं जातिनिर्देशादनुवृत्तिनिर्देशस्येनाकारेण ग्रहणमाकारस्य सिद्धम् । **'अष्टन आ विभक्तौ'** इत्यत्र तु सत्यपि जातिनिर्देशे दीर्घोच्चारणसामर्थ्याद्ध्रस्वस्य ग्रहणं न भवति । अन्यथा ह्रस्वमेवोच्चारयेत् । **'प्लुतश्च विषये स्मृतः'** इति न्यायात् प्लुतस्याग्रहणम् ॥

(उद्द्योतः) तत्रापि पक्षे 'अस्य च्वौ' इत्यादौ दोषो नेत्याह—भाष्ये—**आकृतिग्रहणादिति** ॥ तदाह—**अकारजातिरिति** ॥ **सर्वप्रदेशेष्विति** । प्रत्याहारे 'अस्य च्वौ' इत्यादौ च । अकारव्यक्तीनामानन्त्यमाश्रित्य वार्तिककृता वर्णसमाम्नायस्थस्य विवृतत्वेऽपि धात्वादिस्थस्यापि विवृतोपदेशो नोदितः । भाष्यकृता तु प्रयोगस्थानां प्रत्याहारस्थैर्ग्रहणाय तत्र जातिनिर्देशे आवश्यके जाते विवृतत्वप्रतिज्ञानेनैव सर्वसिद्धेः स दोषो वारितः । **'अस्य च्वौ'** इत्यादौ तु सत्यपि विवृतत्वेऽनण्त्वात्सवर्णग्रहणं न स्यादित्यपि जातिनिर्देशेनैव परिहृतम् । एवं च **'अणुदित्–'** सूत्रेऽण्ग्रहणं न कार्यमित्याशयः ॥ **तस्या एवेति** । तस्याश्रयव्यक्तिद्वारेत्यर्थः ॥ तत्र प्रत्यापत्तिवाक्ये **तपरनिर्देशात्** षण्णामेकशेषनिर्देशाद्वा ह्रस्वस्यैव संवृतत्वं बोध्यम् ॥ ननु जातिनिर्देशेऽतिप्रसङ्ग इत्याह—**अष्टन इति** ॥ **अन्यथा ह्रस्वमेवेति** । न च तन्निर्देशेऽन्तरतमपरिभाषया दीर्घो न स्यादिति दीर्घविधानम्, दीर्घनिर्देशे तु तत्सामर्थ्यात्तस्यापि विधानम्, जातिग्रहणादन्यस्यापीति **वाच्यम्** । दीर्घनिर्देशसामर्थ्येनान्तरतमपरिभाषाबाधकल्पनापेक्षया ह्रस्वानुपस्थितेरेव कल्पने लाघवमित्याशयात् ॥ ननु दीर्घोच्चारणसामर्थ्यान्मा भूद्ध्रस्वः, प्लुतस्तु स्यादत आह—**प्लुतश्चेति** । **विषये**=दूराद्धूतादौ । अनेनापि प्लुतविधानेंऽशेऽनुवाददोषः स्यादिति भावः ॥

(सिद्धान्तसाधकभाष्यम्)

*तद्वच्च तपरकरणम् *

एवं च कृत्वा तपराः क्रियन्ते-आकृतिग्रहणेनातिप्रसक्तमिति ॥

(प्रदीपः) **तद्वच्चेति** । **स** आकृतिपक्षो यत्रास्ति-तद्वत् । अथवा वत्यन्तमेतत्, तत्र न्यायेनाकृतिपक्षस्य स्थापितत्वात्तपरेष्वपि स एव पक्षः स्थित इत्यर्थः ॥

(उद्द्योतः) 'सर्वत्राकृतिर्निर्दिष्टा' इत्यत्र ज्ञापकमाह—भाष्ये—**तद्वच्चेति** ॥ सादृश्ये वतिभ्रमं व्यावर्तयति—**स इति** ॥ **अथवा वत्यन्तमेतदिति** । तदा 'तद्वत्' इत्यस्य 'अस्य च्वौ' इत्यादिवदित्यर्थः ॥ तदाह—**तत्र न्यायेनेति** । तत्र—'अस्य च्वौ' इत्यादौ । आकृतिग्रहणप्रयुक्तातिप्रसङ्गनिवारणार्थमेव हि तत्र तत्र तपरकरणम् ॥ जातिपक्षेऽपि विवृतत्वप्रतिज्ञा 'अकः सवर्णे–' इत्यादेः 'दण्डानतिः' इत्यादौ दीर्घार्थमावश्यिकैव । एवं प्रत्यापत्तिवचोऽप्यावश्यकमेव । तुल्यन्यायाज्जातिग्रहणप्रयुक्तातिप्रसङ्गनिवारणाय तपरत्ववद् विधेये 'खट्वादीनाम्' इत्यादौ सद्वारणाय 'अप्रत्ययः' इत्येतदिति बोधितम् । अत्र पक्षेऽण्ग्रहणप्रत्याख्यानेऽपि ऋऌवर्णयोः सावर्ण्येन समानजातित्वातिदेशान्न दोष इति भावः ॥

(सिद्धान्तदूषकभाष्यम्)

ननु च सवर्णग्रहणेनातिप्रसक्तमिति कृत्वा तपराः क्रियेरन् ॥

(सिद्धान्तभूषकभाष्यम्)

प्रत्याख्यायते तत् *सवर्णेऽण्ग्रहणमपरिभाष्यमाकृतिग्रहणादनन्यत्वाच्च* इति ॥

(सिद्धान्ते आकृतिग्रहणावश्यकत्वबोधकं भाष्यम्)

हल्ग्रहणेषु च

किम् ?

"आकृतिग्रहणात्सिद्धम्" इत्येव । 'झलो झलि'–अवात्ताम्, अवात्त । यत्रैतन्नास्ति—अण् सवर्णान्गृह्णाति–इति ॥

(प्रदीपः) **हल्ग्रहणेषु चेति** । अवश्याश्रयणीयत्वमाकृतिपक्षस्य दर्शयति । व्यक्तिपक्षे ह्येकस्यैव तकारस्यानुकरणं खफछठथेत्यत्र तकार इति द्वयोस्तकारयोर्झल्त्वं न स्यात्, अपि त्वेकस्यैवेति 'अवात्ताम्' इत्यत्र सिज्लोपो न स्यात्, 'अभिरथाः' इत्यादावेव स्यात् ॥

(उद्द्योतः) **अवात्तामिति** । वसेर्लुङ्, तसस्ताम्, सिच्, 'सः सि–' इति तत्वम्, 'वदव्रज–' इति वृद्धिः, 'झलो झलि' इति सलोपः ॥ ननु वचनसामर्थ्याज्झल्त्वद्वयेऽपि भविष्यतीत्यत आह—**अभिरथा इति** । भिदेर्लुङि सिचि रूपम् ॥

(१२ सिद्धान्तसमाधानवार्तिकम् ॥ ८ ॥)

॥ * ॥ रूपसामान्याद्वा ॥ * ॥

(भाष्यम्)

रूपसामान्याद्वा सिद्धमेतत् । तद्यथा–'तानेव शाटकानाच्छादयामः, ये मथुरायाम्' 'तानेव शालीन् भुञ्ज्महे, ये मगधेषु' 'तदेवेदं भवतः कार्षापणं, यन्मथुरायां गृहीतम्', अन्यस्मिंश्चान्यस्मिंश्च रूपसामान्यात् 'तदेवेदम्' इति भवति । एवमिहापि रूपसामान्यात्सिद्धम् ॥ १ ॥

(प्रदीपः) **रूपसामान्यादिति** । व्यक्तिनिर्देशेऽपि भेदापरामर्शेन लोकवदभेदव्यवहारोऽस्तीति सिद्धमिष्टम् । व्यक्तिव्यतिरिक्तं तु सामान्यं भवतु मा वा भूत्, सर्वथा लोक इव शास्त्रे व्यवहार इत्यर्थः ॥ १ ॥

(उद्द्योतः) आकृत्यनाश्रयणेऽप्याह—भाष्ये **रूपसामान्यादिति** ॥ तद् व्याचष्टे—**व्यक्तीति** ॥ **अभेदव्यवहार इति** । रूपसादृश्यनिबन्धनप्रत्यभिज्ञाकृताभेदव्यवहार इत्यर्थः । अल्पमहत्स्थूलकृशह्रस्वदीर्घगोघटादिषु 'गौः' 'घटः' इत्यादिव्यवहारवदिति भावः ॥ एवं च व्यक्तिव्यतिरिक्तजातिस्वीकारोऽपि व्यर्थ एवेत्याशयेनाह—**व्यक्तिव्यतिरिक्तं त्विति** ॥ **मा वेति** । अनुगतप्रतीतिव्यवहारयोः सादृश्येनैवोपपत्तेरिति भावः । सादृश्यं चात्र समानध्वनिकृतम् ॥ १ ॥

(इति जातिपक्षः ॥)

(शिवसूत्रम्)

॥ ऋलृक् ॥ २ ॥

(लृकारप्रयोजनाधिकरणम्)

(आक्षेपभाष्यम्)

अथ लृकारोपदेशः किमर्थः ?

(उद्योतः) ऋलृक् । भाष्ये-अथ लृकारेति । यद्यप्येतच्चतुर्दशसूत्रीविवृतौ नन्दीश्वरकृतकाशिकायामनेकेषामृषीणां नानाविधार्थजिज्ञासायां शिवेन सर्वजिज्ञासानिवृत्तये एषा ढक्कानिनादेन प्रकाशितेत्युक्तम्-इति-इदमनुपपन्नम्, तथापि पाणिन्युद्देश्यकं फलमस्ति न वा-इति-एतत्तात्पर्यम् । अन्त्यवर्णचतुर्दशं तु पाणिन्युद्देशेनैवोपदिष्टमित्यपि तत्रैव स्पष्टम् ॥

(आक्षेपबाधकभाष्यम्)

किं विशेषेण लृकारोपदेशश्चोद्यते, न पुनरन्येषामपि वर्णानामुपदेशश्चोद्येत ।

यदि किंचिदन्येषामपि वर्णानामुपदेशे प्रयोजनमस्ति, लृकारोपदेशस्यापि तत् भवितुमर्हति, को वा विशेषः ?

(आक्षेपसाधकभाष्यम्)

अयमस्ति विशेषः—अस्य हि लृकारस्याल्पीयांश्चैव प्रयोगविषयः । यश्चापि प्रयोगविषयः सोऽपि क्लृपिस्थस्य । क्लृपेश्च लत्वमसिद्धम्, तस्यासिद्धत्वादृकारस्यैवाच्कार्याणि भविष्यन्ति । नार्थ लृकारोपदेशेन ॥

(प्रदीपः) ऋलृक् । अल्पीयानिति । ऋकारापेक्षः प्रकर्षः । ऋकारस्याल्पः प्रयोगस्ततोऽप्यस्याल्पतर इत्यर्थः ॥ अल्पप्रयोगस्यापि कार्यार्थं उपदेशः कर्तव्य इत्याशङ्क्याह—यश्चापीति । तत्र ऋकारावस्थायामेवोदात्तादिषु कृतेषु 'स्थानेऽन्तरतमः' इति स्थानिसदृश लृकारो भविष्यति ॥

(उद्योतः) भाष्ये 'प्रयोगविषयः' इति कर्मधारयः । प्रयोगादन्यत्रानभिव्यज्यमानतया प्रयोगो विषय इत्युक्तः ॥ अल्पेति । यथा 'मुञ्चावण्' इत्यादेः ॥ ननु ऋकारे कार्यप्रवृत्तावपि लृकारे कथं तत्कार्योदात्तत्वादीनां दर्शनमत आह—तत्रेति ॥ स्थानेऽन्तरतम इतीति । यद्यपि 'कृपो रो लः' इत्यत्र रेफलकारयोः स्थान्यादेशभावस्तथापि तद्द्वारा ऋकारलृकारयोरपि स इति भावः ॥

(भाष्यम्)

अत उत्तरं पठति—

(११ समाधानवार्तिकम् ॥ १ ॥)

॥ * ॥ लृकारोपदेशो यदृच्छाशक्तिजानुकरणप्लुत्याद्यर्थः ॥ * ॥

(भाष्यम्)

लृकारोपदेशः क्रियते—यदृच्छाशब्दार्थोऽशक्तिजानुकरणार्थः प्लुत्याद्यर्थश्च ?

यदृच्छाशब्दार्थस्तावत्—यदृच्छया कश्चिद् लृतको नाम । तस्मिन्नच्कार्याणि यथा स्युः—दध्य्लृतकाय देहि, मध्लृतकाय देहि, उदङ्ङ्लृतकोऽगमत्, प्रत्यङ्ङ्लृतकोऽगमत् ।

चतुष्टयी शब्दानां प्रवृत्तिः—जातिशब्दाः, गुणशब्दाः, क्रियाशब्दाः, यदृच्छाशब्दाश्चतुर्थाः ॥

(प्रदीपः) यदृच्छेति । अर्थगतं प्रवृत्तिनिमित्तमनपेक्ष्य यः शब्दः प्रयोक्त्रभिप्रायेणैव प्रवर्तते स यदृच्छाशब्दो डित्थादिः ॥ ऋकारलृकारयोः सवर्णविधिरित्यस्य वार्तिककारवाक्यत्वात्सूत्रकारेणानाश्रितत्वादत्र लृकारोपदेशः कृतः ॥ अर्थवत्सूत्रारम्भाच्चाव्युत्पन्ना यदृच्छाशब्दाः सन्तीत्यवगम्यते । गाव्यादीनां तु गवादिभिर्निवर्तितत्वादसाधुत्वम् । ऋतकशब्दस्त्वर्थाश्रयेणैव विनियुक्त इति लृतकशब्दस्यानिवर्तकः ॥

(उद्योतः) अर्थगतमिति । शब्दातिरिक्तमर्थरूपमित्यर्थः । यद्वा व्यक्तेरेव वाच्यता । तस्यां च प्रकारताविशेष्यताख्यविषयताद्वयाङ्गीकाराच्छक्तिग्रहोपपत्तेः सविकल्पकोपपत्तिश्च तत इति भावः ॥ प्रयोक्त्रभिप्रायेणैवेति । शक्तिबोधनं प्रयोक्त्रधीनमिति भावः । अन्यथा शब्दार्थसंबन्धस्यानित्यतापत्तिः । एवं च 'स्वेच्छयैकस्यां व्यक्तौ सङ्केत्यमानः शब्दः-यदृच्छाशब्दः' इति बोध्यम् ॥ ननु ऋकारस्याच्त्वे ऋलृवर्णयोः सावर्ण्यात् ऋकारेण लृकारस्यापि ग्रहणादच्कार्यसिद्धौ किं लृकारोपदेशेनेत्यत आह—ऋकारेति ॥ उपदेशः कृत इति । पाणिनये शिवेन इति शेषः । वस्तुतोऽत्र तस्यानुपदेशेऽप्रामाणिकत्वशङ्कया सवर्णविधिरपि तयोर्वक्तुमशक्य इति तदुपदेशः ॥ सवर्णविधिद्वारकफलमपि स्वलत्रय एवेति तत्रैव प्रयोजनोपन्यास इति बोध्यम् ॥ ननु सन्तमसन्तं वा क्रियायोगमर्थगतमङ्गीकृत्य डित्थादीनामपि व्युत्पत्तेरर्थगतार्थरूपप्रवृत्तिनिमित्तानपेक्षशब्दसत्त्वे किं मानमत आह—अर्थवदिति । चिन्त्यमिदम्, बहुत्पूर्वे तस्य चारितार्थ्यात् ॥ एतदर्थं तद्धितपदं तद्विशिष्टपरम् । 'अप्रत्ययः' इत्युक्तेश्च पचतकीत्यादौ न दोषः । प्रत्ययश्च तद्धितभिन्न एव । मधुपटवस्तिष्ठन्तीत्यादौ 'यं समुदायं' इति न्यायेन न दोषः-इति कैयटाशयमन्ये ॥ ननु लृतकस्यासाधुत्वात्कथं शास्त्रविषयता-इत्यत आह—गाव्यादीनामिति ॥ ऋतकेन लृतकानिवृत्तौ हेतुः-अर्थाश्रयेणेति । स्वगतक्रियारूपार्थाश्रयेणेत्यर्थः । अर्थतः सजातीयस्यैव निवृत्तिः । एकप्रवृत्तिनिमित्तकत्वे सति अन्वाख्यातमनन्वाख्यातस्य निवर्तकमिति भावः । तत् ध्वनयन्नाह—भाष्ये-चतुष्टयीति । शब्दानामर्थे या प्रवृत्तिः सा प्रवृत्तिनिमित्तभेदात्प्रकारचतुष्टयवतीत्यर्थः । तत्र यदृच्छाशब्दो नाम वक्त्रा स्वेच्छया संनिवेशितः । स चानेकविधः—एकव्यक्तिसंनिवेशितो डित्थादिरेकः । तत्र न किंचिदतिरिक्तं प्रवृत्तिनिमित्तम्, आनन्त्यव्यभिचारयोरभावात् । किंतु शक्यस्यैवार्थस्य विषयताद्वयेन भानम् । तदुत्तरत्वादेः प्रकारत्वावच्छिन्नः स एवार्थः । यद्वा शब्दपराद्वाच्येऽर्थे एव त्वादिः । एवं कादिपदानां कादीनामेकत्वमते तेषु शक्तिः । ततो डित्थादिपदादिव शक्यार्थे एव त्वादिः । कुत्वमिति-कुरिति च पर्यायौ । अनेकत्वमते तत्तज्जात्युपलक्षिते शा । टिघुभादीनां तु तच्छब्दानामानन्त्यात्तत्पदमेव प्रवृत्तिनिमित्तम् । तदेव

च तदुत्तर-त्वाद्यर्थः । भत्वादिपदैर्भादिसंज्ञैवोच्यते । अत एव वृद्धि-सूत्रे वक्ष्यति—"कुत्वं कस्मान्न भवति चोः कुः पदस्येति । भत्वात् । कथं भसंज्ञा" इति । अनेन च भाष्येण कुकुत्वपदयोः भत्वभसंज्ञापदयोः पर्यायत्वं स्पष्टमेव । संज्ञा च पदमेव ॥

(वार्तिकविवरणभाष्यम्)

अशक्तिजानुकरणार्थः । अशक्त्या कयाचिद् ब्राह्मण्या ऋतक इति प्रयोक्तव्ये ऌतक इति प्रयुक्तम् । तस्यानुकरणं-ब्राह्मण्यॢतक इत्याह, कुमार्यॢतक इत्याह ॥

(प्रदीपः) **अशक्तिजेति ।** अशक्तिजानुकरणस्य जातिशब्दत्वमिच्छन्ति । यस्मादनुक्रियमाणे शब्दे या जातिः समवेता तत्संबद्धमनुकार्यमनुकरणं प्रत्याययति ॥

(उद्द्योतः) ननु चतुर्विधेष्वनुकरणशब्दः क्वान्तर्भवतीत्यत आह—**अशक्तिजेति ॥ यस्मादिति ।** अनुक्रियमाणशब्दव्यक्तयो बह्वयः । प्रत्यभिज्ञा तु जातिनिबन्धना रूपसादृश्यनिबन्धना चेति भावः ॥ एतेऽपि यदृच्छाशब्दाः, स्वेच्छयैव वक्ता शब्दपरतया प्रयोगात्—इत्यन्ये ॥

(वार्तिकविवरणभाष्यम्)

प्लुत्याद्यर्थश्च ऌकारोपदेशः कर्तव्यः ॥

के पुनः प्लुत्यादयः ?

प्लुतिद्विर्वचनस्वरिताः । कॢ३प्तशिख । कॢप्तः । प्रकॢप्तः । प्लुत्यादिषु कार्येषु कृपेर्लत्वं सिद्धम्, तस्य सिद्धत्वादच्कार्याणि न सिध्यन्ति । तस्मात् ऌकारोपदेशः क्रियते ॥

(उद्द्योतः) **प्लुत्यादिकं च 'गुरोरनृतः'** इति प्लुतः, **'अनचि च'** इति द्वित्वम्, प्रपूर्वात्कृपेरन्तर्भावितण्यर्थात्कर्मणि क्ते **'गतिरनन्तरः'** इति पूर्वपदप्रकृतिस्वरे वर्ज्यमानस्वरेण शिष्टस्यानुदात्तत्वे **'उदात्तादनुदात्तस्य–'** इति स्वरितत्वम् ॥ **'अनृतः'** इति निषेधस्तु न, ऋदित्ऌदिदिति पृथगनुबन्धकरणेन क्वचित्परस्पराग्रहणज्ञापनात् ॥

(प्रयोजननिराकरणभाष्यम्)

नैतानि सन्ति प्रयोजनानि ॥

(३४ प्रयोजनप्रत्याख्यानवार्तिकम् ॥ २ ॥)

॥*॥ न्याय्यभावात्कल्पनं संज्ञादिषु ॥*॥

(भाष्यम्)

न्याय्यस्य ऋतकशब्दस्य भावात् कल्पनं संज्ञादिषु साधु मन्यन्ते—ऋतक एवासौ, न ऌतक इति ॥

(प्रदीपः) **न्याय्यभावादिति ।** ऋतकशब्दो न्याय्यः, **'कृदन्तं नाम कुर्यात्'** इति स्मृतावुक्तत्वात् । 'ऋतिः' सौत्रो धातुः, तत औणादिकः **'क्वुन्शिल्पिसंज्ञयोरपूर्वस्यापि'** इति क्वुन्प्रत्ययः ॥ **संज्ञादिष्विति ।** आदिशब्देनैतद्दर्शयति—जातिगुणक्रियानिमित्ता अपि शास्त्रान्विता एव प्रयोक्तव्या इति ॥ सर्वशब्दव्युत्पत्तिपक्षे किं **'अर्थवत्–'**सूत्रेणेति चेत्, शिष्टप्रयुक्तानामेवाव्युत्पत्तिपक्षोऽप्यस्तीति ज्ञापनाय **'अर्थवत्–'** सूत्रोपादानम् । अनुकरणशब्दानामव्युत्पन्नत्वात्तदर्थं च ॥

(उद्द्योतः) **न्याय्य इति ।** संज्ञात्वेन कल्पयितुमिति शेषः ॥ तत्र हेतुमाह—**कृदन्तमिति ॥** प्रकृतिप्रत्ययादिविभागेनान्वाख्यातत्वमेव न्याय्यत्वमित्याशयेन शङ्कते—**सर्वशब्देति ।** शिष्टप्रयुक्तत्वमपि न्याय्यत्वमिति परिहारः ॥ न च तस्यैव प्रयोगे ऌतकशब्दो बोधकोऽपि न स्यादिति **वाच्यम् ।** बोधकत्वेऽप्यसाधुत्वान्न शास्त्रीयकार्यनिमित्तत्वमित्याशयात् । तद्ध्वनितं भाष्ये—**"साधु मन्यन्ते"** इति ग्रन्थेन ॥ **ऋतक एवासाविति ।** ऋतकशब्दप्रतिपाद्य एवासौ, न ऌतकशब्दप्रतिपाद्य इत्यर्थः ॥

(व्याख्यान्तरभाष्यम्)

अपर आह—न्याय्य ऋतकशब्दः शास्त्रान्वितोऽस्ति, स कल्पयितव्यः साधुः संज्ञादिषु । ऋतक एवासौ, न ऌतकः ॥

(प्रदीपः) **अपर आहेति ।** पूर्वमुक्तम्—ऋतक शब्द एव न्याय्यत्वान्नियोक्तव्यः, न तु ऌतकशब्द इति । इदानीं तु ऋतकशब्दस्यैवायमपभ्रंशोऽशक्तिजत्वात् ऌतक शब्द इत्युच्यते ॥

(उद्द्योतः) **इदानीं त्विति ।** भाष्ये **'कल्पयितव्यः'** इत्यस्य विनियुक्तत्वेन ज्ञेय इत्यर्थः । साधुर्ऋतक एव नामत्वेन कृतो न ऌतकः । अशक्त्या तु तथोच्चारणमित्यपभ्रंशत्वान्न शास्त्रविषय इति भावः ॥ **अशक्तिजत्वादिति ।** जिह्वाऽपाटवजत्वादित्यर्थः । एवं चासाधुरेवेति भावः ॥

(प्रत्याख्यानबाधकभाष्यम्)

अयं तर्हि यदृच्छाशब्दोऽपरिहार्यः—ऌफिडः, ऌफिड्डः ॥

(प्रदीपः) **अयं तर्हीति ।** ऋतकशब्दोऽन्वाख्यातत्वाद्भवतु ऌतकशब्दस्य निवर्तकः । ऋफिड-ऋफिड्ड-इत्येतौ त्वनन्वाख्याताविति कथं ऌफिड-ऌफिड्ड-इत्येतयोर्निवर्तकौ स्यातामिति भावः ॥

(उद्द्योतः) ऌतकात् ऌफिड्डे वैषम्यं दर्शयति—**ऋतकशब्द इति ॥ ऌतकशब्दस्येति ।** अनन्वाख्यातस्येत्यादिः ॥

(प्रत्याख्यानसाधकभाष्यम्)

एषोऽपि ऋफिडः, ऋफिड्डश्च ।

कथम् ?

अर्तिप्रवृत्तिश्चैव हि लोके लक्ष्यते । फिडफिड्डावौणादिकौ प्रत्ययौ ॥

त्रयी च शब्दानां प्रवृत्तिः—जातिशब्दाः, गुणशब्दाः, क्रियाशब्दा इति । न सन्ति यदृच्छाशब्दाः ॥

(प्रदीपः) **एषोऽपीति । 'उणादयो बहुलम्'** इत्येतावन्वाख्याताविति भावः ॥

अर्तिप्रवृत्तिरिति । अर्तेः फिडफिड्डप्रकृतित्वेन प्रवृत्तिरित्यर्थः ॥

न सन्तीति । अद्यत्वेऽपि यदा नाम क्रियते, तदा प्रशस्यरूपा क्रिया गुणो वाऽध्यारोप्यत इति भावः ॥

(उद्योतः) फिडफिड्डयोरुणादिष्वदर्शनादाह—**उणादय इति** । बाहुलकसिद्धावेतावित्यर्थः ॥ **अर्तिप्रवृत्तिश्चैवेति** । तथा च फिडफिड्डयोः स एव प्रकृतिर्न तु 'ऌ' इति धात्वन्तरं कल्प्यम् । **'संज्ञासु धातुरूपाणि'** इति तु अनादिशिष्टप्रयोगसाधने उपायमात्रं न त्वाधुनिकक्रियमाणसंज्ञाऽनुग्राहकमिति भावः ॥ एवं च देशभाषानुसारेण क्रियमाणं 'कूची-मञ्ची' इत्याद्यसाधु, शास्त्राविषयश्चेत्युक्तम् ॥ **अर्तेरिति** । यतस्तस्य लोके प्रवृत्तिर्लक्ष्यते अतः फिडादिप्रकृतित्वेनापि तस्यैव प्रवृत्तिरित्यर्थः ॥ एवं यदृच्छाशब्दानङ्गीकृत्य शास्त्रान्वितानां कचिच्छिष्टप्रयुक्तानामेव यत्रकुत्रचित्संज्ञात्वेन विनियोगः, नान्येषाम्—इत्येवं ऌतकऌफिडादीनां शास्त्रविषयत्वाभावान्न तदर्थो ऌकारोपदेश इत्युक्तम् ॥ इदानीं **'न सन्त्येव यदृच्छाशब्दाः'** इति पक्षावष्टम्भेन तदर्थत्वं प्रत्याचष्टे—भाष्ये—**त्रयी चेति** । चेनेदं ध्वनितम् ॥ नन्वेवं डित्थादीनां कान्तर्भावोऽत आह—**अथर्वेऽपीति** । एवं च सर्वेऽपि व्युत्पन्नाः क्रियादिशब्दा एवेति भावः ॥ **प्रशस्तरूपेति** । अत्यन्तप्रशंसायोग्येत्यर्थः । एवं च येषां क्रियागुणादिप्रवृत्तिनिमित्तकत्वं तेषां क्रियाद्यारोपेणार्थबोधकत्वमिति तात्पर्यम् । यद्वा पूर्वपूर्वडित्थादिगतप्रशस्तगुणक्रियारोपेण तत्प्रवृत्तिनिमित्तक एव डित्थादिभ्यो बोधः । आद्ये डित्थे तु तद्व्यक्तेरेव विषयताद्वयेन ज्ञानमिति सैव प्रवृत्तिनिमित्तमपीति **'तस्य भावः'** इति सूत्रे भाष्ये उपपादयिष्यते ॥

(प्रयोजनवादिभाष्यम्)

अन्यथा कृत्वा प्रयोजनमुक्तम्, अन्यथा कृत्वा परिहारः । सन्ति यदृच्छाशब्दा इति कृत्वा प्रयोजनमुक्तम्, न सन्तीति परिहारः ।

समाने चार्थे शास्त्रान्वितोऽशास्त्रान्वितस्य निवर्तको भवति । तद्यथा-देवदत्तशब्दो देवदिण्णशब्दं निवर्तयति, न गाव्यादीन् ॥

(प्रदीपः) अन्यथा कृत्वेति । अव्युत्पत्तिपक्षाश्रयणेनाचार्येणोपदिष्टो ऌकारः । वार्तिककारस्तु व्युत्पत्तिपक्षाश्रयणेन प्रत्याचष्टे ॥

समाने चेति । इह च भिन्नार्थत्वम् । ऌतकशब्दो हि यदा संज्ञात्वेन विनियुज्यते कचित् पिण्डे तदा तच्छब्दस्वरूपाध्यासः, ऋतके तु विपर्ययः । भिन्नस्वरूपौ चैतौ शब्दाविति भावः ॥

(उद्योतः) अव्युत्पत्तीति । संज्ञाशब्दा अव्युत्पन्ना इति पक्षाश्रयणेनेत्यर्थः ॥ **आचार्येणेति** । शिवो वेदपुरुषो वाऽत्राचार्यः । एवञ्च यदृच्छाशब्दसद्भावाश्रयेण प्रयोजने उक्ते तदनाश्रयणेन तत्प्रयोजननिराकरणमयुक्तमिति भावः ॥ ऋतकशब्दो ऌतकशब्दस्य साधुत्वाभावकल्पक इत्याद्यं दूषणमप्ययुक्तमित्याह—भाष्ये—**समाने चेति** ॥ तत्रार्थशब्दः प्रवृत्तिनिमित्ताभिप्राय इत्याह—**इह चेति** । तच्छब्दस्वरूपस्य व्यक्तिस्वरूपस्य वाऽर्थे प्रवृत्तिनिमित्तत्वेनाध्यास इत्यर्थः ॥ **विपर्यय इति** । क्रिया प्रवृत्तिनिमित्तमित्यर्थः ॥ **भिन्नस्वरूपौ**—भिन्नप्रवृत्तिनिमित्तौ । यदि तु ऋतकोऽपि शब्दप्रवृत्तिनिमित्तकस्तदा भिन्नस्वरूपत्वादेव प्रवृत्तिनिमित्तविपर्ययः । व्यक्तेरेव प्रवृत्तिनिमित्तत्वमिति पक्षे—ऋतकसङ्केतविषयव्यक्तेर्ऌतकसङ्केतविषयव्यक्तिर्भिन्नैवेति तद्विपर्ययोऽस्त्येवेति बोध्यम् ॥

(प्रत्याख्यानभाष्यम्)

नैष दोषः । पक्षान्तरैरपि परिहारा भवन्ति ॥

(प्रदीपः) पक्षान्तरैरपीति । यथा द्रव्यपक्षे **'सरूपाणां—'** इत्यस्यारम्भः, जातिपक्षे तु प्रत्याख्यानम्; एवमस्यापीत्यर्थः । अव्युत्पन्नसंज्ञाशब्दपक्षेऽपि पारम्पर्यायाताः शिष्टप्रयुक्ता एव संज्ञाः कर्तव्याः ॥

(उद्योतः) भाष्ये समाधत्ते—**पक्षान्तरैरपीति** ॥ **जातिपक्षे त्विति** । यत्तु—अक्षादिनानार्थानामेकशेषाय तत्पक्षेऽप्यावश्यकम्—इति, तत्तु जातिगतजातिस्वीकारेण परिहृतम् । **पक्षान्तरैरपि परिहारा भवन्तीति** वार्तिककृतैवमुक्तम् ॥ वस्तुतश्चतुष्टयीपक्षेऽपि दोषपरिहारः सुकरः ॥ यदुक्तम्—ऋतको न ऌतकनिवर्तक इति । मा भूत्तस्य निवर्तकत्वम्, शिष्टप्रयोगाभावात्तु तन्निवृत्तिः ॥ न्याय्यत्वमपि वार्तिके शिष्टप्रयुक्तत्वमेवेत्यभिसन्धाय भगवताऽनुक्तमपि स्वयं मन्दबुद्ध्यनुग्रहाय स्फुटमाह—**अव्युत्पन्नेति** ॥ **पारम्पर्यायाताः**—अनादयः । एवं च शिष्टाप्रयुक्ता यदृच्छाशब्दा असाधुत्वेन शास्त्राविषया इति भाष्यतात्पर्यम् ॥ यत्तु—चतुष्टयीति पक्षे ऌतकादीनां टिघुभादिवच्छास्त्रविषयत्वमेवेत्यसाद्भाष्याल्लभ्यते—इति । तन्न, पक्षभेदेनैकस्य शास्त्रविषयत्वतदविषयत्वाङ्गीकारे **'न वेति'**सूत्रस्थभाष्यविरोधात् । टिघुभादीनां पाणिन्यादिशिष्टप्रयुक्तत्वेन साधुत्वाच्छास्त्रविषयत्वेऽपि अन्येषां तद्विषयत्वे मानाभावाच्च । किञ्च साध्वसाधुबहिर्भूतानामपि शास्त्रविषयत्वे **'साध्वनुशासनेऽस्मिन्शास्त्रे'** इति तत्र तत्र भाष्योक्त्यसङ्गतिः । किञ्च शास्त्रविषयत्वमथ तद्वद्वयसाधुत्वाभाव इत्यशक्यमिति दिक् ॥

(३५ द्वितीयप्रयोजनप्रत्याख्यानवार्तिकम् ॥ ३ ॥)

॥ * ॥ अनुकरणं शिष्टाशिष्टाप्रतिषिद्धेषु यथा लौकिकवैदिकेषु ॥ * ॥

(भाष्यम्)

अनुकरणं हि शिष्टस्य साधु भवति, अशिष्टाप्रतिषिद्धस्य वा नैव तद्दोषाय भवति नाभ्युदयाय । यथा लौकिकवैदिकेषु । यथा लौकिकेषु वैदिकेषु च कृतान्तेषु ।

लोके तावत्—य एवमसौ ददाति, य एवमसौ यजते, य एवमसावधीते—इति तस्यानुकुर्वन् दद्याच्च यजेत वाऽधीयीत च सोऽप्यभ्युदयेन युज्यते ॥

वेदेऽपि—"य एवं विश्वसृजः सत्राण्यध्यासते" इति तेषामनुकुर्वन् तद्वत्सत्राण्यध्यासीत सोऽप्यभ्युदयेन युज्यते ॥

अशिष्टाप्रतिषिद्धं—य एवमसौ हिक्कति, य एवमसौ हसति, य एवमसौ कण्डूयति-इति तस्यानुकुर्वन् हिक्केच्च हसेच्च कण्डूयेच्च, नैव तद्दोषाय स्यान्नाभ्युदयाय ॥

यस्तु खल्वेवमसौ ब्राह्मणं हन्ति, एवमसौ सुरां पिबति-इति तस्यानुकुर्वन् ब्राह्मणं हन्यात्सुरां वा पिबेत्, सोऽपि मन्ये पतितः स्यात् ॥

(प्रदीपः) प्रयोजनान्तरमपि वार्तिककारः प्रत्याचष्टे—**अनुकरणमिति** । अनुकार्यस्य दुष्टत्वादनुकरणेऽपि दुष्टत्वं मन्यते, सुरापाणानुकरणवत् ॥

(उद्द्योतः) अनुकरणं शिष्टस्य वा अशिष्टाप्रतिषिद्धस्य वा भवति । तत्राद्यं साधु, अन्त्यं न दोषाय नाप्यभ्युदयाय—इति भाष्येऽन्वयः । अर्थात्प्रतिषिद्धानुकरणस्य दुष्टत्वं बोध्यम् ॥ ननु शिष्टानुकरणं नासाधु—अशिष्टाप्रतिषिद्धस्य वा नासाधु । आद्यस्याभ्युदयजनकत्वात्, अन्त्यस्याभ्युदयाजनकत्वेऽपि दोषाजनकत्वात् । एवञ्च प्रकृते किमायातमत आह—**अनुकार्यस्य दुष्टत्वादिति** । अर्थलभ्यं तदादाय प्रकृतोपयोग इत्यर्थः ॥ अत एव भाष्ये तद्दृष्टान्तेनोपपादयिष्यति—**यस्तु खल्विति** । एवं चासाध्वनुकरणस्यासाधुत्वाच्छास्त्राविषयत्वात्तदर्थता लृकारोपदेशस्य न युज्यत इति भावः ॥ भाष्ये—**यजेत वेति** । यागोऽत्र स्मार्तो ग्राह्यः ॥

(प्रयोजनसमर्थनभाष्यम्)

विषम उपन्यासः । यश्चैवं हन्ति, यश्चानुहन्ति, उभौ तौ हतः । यश्चापि पिबति, यश्चानुपिबति, उभौ तौ पिबतः ॥

यस्तु खल्वेवमसौ ब्राह्मणं हन्ति-एवमसौ सुरां पिबति-इति तस्यानुकुर्वन्स्नातानुलिप्तो माल्यगुणकण्ठः कदलीस्तम्भं छिन्द्यात्-पयो वा पिबेत्, न स मन्ये पतितः स्यात् ॥

(प्रदीपः) भाष्यकारस्त्वनुकरणार्थत्वं समर्थयते—**विषम इति** । न ह्यनुकार्यस्य दोषेणानुकरणस्य दुष्टत्वम् । विहितकरणाद्धि धर्मोत्पत्तिः प्रतिषिद्धाचरणाच्चाधर्मो भवति, न त्वनुमानेन धर्माधर्मयोर्व्यवस्थेति मन्यते । सुरापाणादौ तु तस्या एव क्रियाया अनुष्ठानात्सादृश्याभावाच्चास्त्यनुकरणत्वम् ॥ दानादीनां स्मार्तत्वाल्लौकिकत्वमुच्यते ॥

स्नातानुलिप्त इति—स्वस्थचित्तत्वं दर्शयति । अस्वस्थेन हि चित्तेनाकार्यं क्रियते ॥ **माल्यगुणकण्ठ इति** । लोकमध्ये प्रकाशते—इत्यर्थः । अकार्यं ह्यप्रकाशं क्रियते ॥ लृतकशब्दोऽपि यदा लृतकार्थे प्रयुज्यते तदाऽपशब्दः । यदाऽनुकार्यं प्रत्याययति तदा साधुरेव, अर्थभेदात्; अश्वगोण्यादिवत् ॥

(उद्द्योतः) **सादृश्याभावादिति** । न चैकजातीयेष्वपि व्यक्तिभेदेन सादृश्यसंभवः । सुरापानत्वादेरेव तादृशस्थले सादृश्येन तदतिरिक्तसादृश्याभावादित्याशयात् । तदाह—**नास्त्येति** ॥ दानादीनां कथं लौकिकत्वेनोपन्यासोऽत आह—**स्मार्तत्वादिति** ॥ **अस्वस्थेनेति** । आस्तिकत्वे सत्यपीति भावः ॥ **माल्यगुणकण्ठ इति** । मालायां साधूनि—माल्यानि=पुष्पाणि, तैर्युक्तो गुणः=स्रक् कण्ठे यस्येत्यर्थः । गड्वादित्वात्परनिपातः ॥ **अकार्यं हीति** । इह लोके भीरुणेत्यर्थः ॥ [अर्थभेदेन साधुत्वे दृष्टान्तमाह—**अश्वेति** ॥]

(वार्तिकार्थनिगमनभाष्यम्)

एवमिहापि य एवमसावपशब्दं प्रयुङ्क्ते-इति तस्यानुकुर्वन्नपशब्दं प्रयुञ्जीत सोऽप्यपशब्दभाक् स्यात् ॥

(उद्द्योतः) भाष्ये प्रयोजनप्रत्याख्यानवादी शङ्कते—**एवमिहापीति** ॥

(उपदेशप्रयोजनभाष्यम्)

अयं त्वन्योऽपशब्दपदार्थकः शब्दः, यदर्थ उपदेशः कर्तव्यः ॥

न चापशब्दपदार्थकः शब्दोऽपशब्दो भवति । अवश्यं चैतदेवं विज्ञेयम् । यो हि मन्यते—अपशब्दपदार्थकः शब्दोऽपशब्दो भवतीति, अपशब्द इत्येव तस्यापशब्दः स्यात् । न चैषोऽपशब्दः ॥

(प्रदीपः) **अपशब्द इत्येवेति** । अस्य हि गाव्यादयोऽपभ्रंशा वाच्याः ॥

(उद्द्योतः) प्रयोजनवादी समाधत्ते—**अयं त्वन्य इति** ॥ **अस्य हीति** । एवं च तत्तदर्थे व्याकरणाननुगतत्वमपशब्दत्वमिति भावः ॥

(प्रयोजनान्तरभाष्यम्)

अयं खल्वपि भूयोऽनुकरणशब्दोऽपरिहार्यः, यदर्थ उपदेशः कर्तव्यः—साध्वॢकारमधीते-मध्वॢकारमधीते—इति ॥

(प्रदीपः) **अयमिति** । 'असाधोरनुकरणं' इत्येतदप्यत्र नास्ति ॥

(उद्द्योतः) भाष्ये तुष्यतु दुर्जनन्यायेन साध्वनुकरणार्थत्वं लृकारोपदेशस्याह—**अयं खल्वपीति** । यद्यप्यर्थशून्यवर्णानां न साधुत्वम्, तथापि वर्णात्कारविधानेन तेषां साधुत्वमिति भावः ॥

(अन्यथासिद्धिबोधकभाष्यम्)

कस्थस्य पुनरेतदनुकरणम् ?

क्लृपिस्थस्य ॥

यदि क्लृपिस्थस्य, क्लृपेश्च लत्वमसिद्धम् । तस्यासिद्धत्वादृकार एवाच्कार्याणि भविष्यन्ति ॥

(प्रयोजनभाष्यम्)

भवेत्तदर्थेन नार्थः स्यात् । अयं त्वन्यः क्लृपिस्थपदार्थकः शब्दः, यदर्थ उपदेशः कर्तव्यः ॥

(प्रदीपः) **भवेदिति** । प्रयोगस्थस्येदमनुकरणम् । प्रयोगे च **'पूर्वत्रासिद्धम्'** इति नास्ति—इति भावः ॥

(उद्द्योतः) भाष्ये—**भवेत्तदर्थेनेति** । तदर्थेन—क्लृपिस्थलृकारार्थेन लृकारस्योपदेशेन प्रयोजनं न भवति—एवं यद्यपि भवेत्, तथापि तदनुकरणार्थेनार्थ इत्यर्थः ॥ ननु क्लृपिस्थस्यासिद्धत्वात्कथं तदनुकरणमत आह—**प्रयोगस्थस्येति** ॥ **प्रयोगे**=अनुकरणप्रयोगे । शास्त्रे तदीयकार्ये वाऽसिद्धत्वं, पौर्वापर्यस्य तत्रैव संभवात्; न चैवं प्रकृते—इति भावः ॥

(खण्डनभाष्यम्)

न कर्तव्यः । इदमवश्यं कर्तव्यम्—"प्रकृतिवद्-

नुकरणं भवति" इति ।

किं प्रयोजनम् ?

'द्विः पचन्त्वित्याह' "तिङ्ङतिङः" (८।१।२८) इति निघातो यथा स्यात् । 'अग्नी इत्याह' ईदूदेद्द्विवचनं प्रगृह्यसंज्ञं भवति-इति प्रगृह्यसंज्ञा यथा स्यात् ॥

(प्रदीपः) प्रकृतिवदिति । तत्र यथा क्लृपेर्लत्वस्यासिद्धत्वादृकारद्वारेण ऌकारस्याच्कार्यं, तथाऽनुकरणस्यापीत्यर्थः । द्विरिति । 'पचन्तु-पचन्तु' इति केनचिदुक्ते 'द्विः पचन्तु' इत्यनुकरणम् । एतच्च क्रियासाधनाद्यनभिधानात्तिङन्तं न भवति । एवं 'अग्नी' इत्यनुकरणं द्व्यर्थानभिधानान्न द्विवचनान्तम् ॥ ननु गम्ऌ-सृप्ऌ-इत्यादिस्थस्य यदाऽनुकरणं तदा कथं प्रकृतिवद्भावः ? 'प्लुतावैच इदुतौ'(?) 'ऌदित'इति ऌकारे परतो यणादेशकरणादित्संज्ञाऽनुवादाच्च धात्वनुबन्धस्य ऌकारस्याच्कार्याण्यनुमीयन्ते, ततस्तदनुकरणस्य सिद्धः प्रकृतिवद्भावः ॥

(उद्द्योतः) ऋकारद्वारेणेति । ऋकारयुक्तेत्यर्थः ॥ भाष्ये— द्विः पचन्त्विति । पचन्त्विति द्विराह-इत्यन्वयः ॥ असत्यतिदेशे तिङन्तत्वाभावे हेतुमाह—एतच्चेति ॥ द्व्यर्थेति । एतदर्थमेव 'द्विवचनं' इत्यन्वर्थसंज्ञाकरणम् ॥ नन्विति । एवञ्च पाठाभावे मूलस्यैवाच्त्वाभावात्कथं तदनुकरणेऽच्कार्यमिति तदर्थं उपदेश आवश्यक इति भावः ॥ अनुमीयन्त इति । इदं चिन्त्यम्, आनुमानिकवचनेन कृतस्य वर्णस्य प्रत्याख्यानायोगात् । तस्मात् 'गम्ऌ' इत्यादिस्थ ऌकारो धर्माजनकत्वान्न साधुरिति वक्तुं युक्तम् । एवं च 'अशक्तिजानुकरण-' इति वार्तिकेऽशक्तिजपदं व्यर्थमिति तात्पर्यम् ॥

(खण्डनोपसंहारभाष्यम्)

यदि प्रकृतिवदनुकरणं भवतीत्युच्यते, अपशब्द एवासौ भवति-कुमार्यृतक इत्याह, ब्राह्मण्यृतक इत्याह । अपशब्दो ह्यस्य प्रकृतिः ॥

(उद्द्योतः) एवं साध्वनुकरणार्थत्वे ऌकारोपदेशस्य 'प्रकृतिवत्-' इत्याश्रयणेन खण्डिते तेनैवाशक्तिजानुकरणार्थत्वमपि खण्डयति पूर्वपक्षी-भाष्ये—यदि प्रकृतिवदिति ॥

(प्रयोजनभाष्यम्)

नैव चापशब्दः प्रकृतिः । न ह्यपशब्दा उपदिश्यन्ते । न चानुपदिष्टा प्रकृतिरस्ति ॥

(प्रदीपः) न चापशब्द इति । सिद्धान्तवादी । प्रकरणाद्धि शास्त्रीया प्रकृतिराश्रीयते, शास्त्रनिबन्धनं च कार्यमतिदिश्यते । अपशब्दश्च न शास्त्रीया प्रकृतिः, अनुपदिष्टत्वात् । न चापशब्दत्वं शास्त्रीयं कार्यं, नापि तदतिदेष्टुं शक्यम् । न हि साधोरसाधुत्वातिदेशो युक्तिमान् । तदेवं भाष्यकारेणाशक्तिजानुकरणार्थत्वमॢकारोपदेशस्य स्थापितम् ॥

(उद्द्योतः) ननु मा भूदपशब्दोपदेशः, प्रकृतित्वं तु कथं नेत्यत आह—प्रकरणादिति । अतिदेशस्य शास्त्रीयत्वमनेन दर्श्यते । तत्र च प्रत्यासत्त्या शास्त्रीयप्रकृत्यादेरेव ग्रहणमुचितमिति भावः ॥ उपलक्षणं भाष्यमित्याह—शास्त्रनिबन्धनं चेति ॥ 'नापि तदतिदेष्टुं' इत्यादि चिन्त्यम्, अब्राह्मणे ब्राह्मणत्वाद्यतिदेशवत् संभवात्—इति कश्चित् ॥ तदेवमिति । अशक्तिजस्य शास्त्रीयप्रकृतित्वाभावान्न तदनुकरणेऽतिदेशप्रवृत्तिरित्यपशब्दत्वाभावादच्कार्यसिद्ध्यर्थं ऌकारोपदेश इत्यर्थः ॥

(३६ तृतीयप्रयोजनप्रत्याख्यानवार्तिकम् ॥ ४ ॥)

॥ * ॥ एकदेशविकृतस्यानन्यत्वात्प्लुत्यादयः ॥ * ॥

(भाष्यम्)

"एकदेशविकृतमनन्यवद्भवति" इति प्लुत्यादयोऽपि भविष्यन्ति ॥

(प्रदीपः) एकदेशविकृतस्येति । ऋकारे रेफभागस्य लत्वे कृते स एव ऋकार इति प्रत्यभिज्ञानादिति भावः ॥

(उद्द्योतः) इदानीं प्लुत्याद्यर्थत्वं तस्य परिहरति भाष्ये—एकादेशेति ॥ रेफभागस्येति । वर्णैकदेशा वर्णग्रहणेन गृह्यन्त इति पक्षे इत्यर्थः ॥ प्रत्यभिज्ञानादिति । एवं च छिन्नपुच्छश्वदृष्टान्तेन लोकन्यायसिद्धमस्य ऋत्वमित्यर्थः । व्याख्यानभाष्ये 'अनन्यवत्' इत्यस्यान्यवन्नेत्यर्थः । अन्यसादृश्यस्यापि निषेधे तत्त्वं दृढीकृतम् ॥

(प्रयोजनवाद्याक्षेपभाष्यम्)

यदि 'एकदेशविकृतमनन्यवद्भवति' इत्युच्यते, "राज्ञः क च" राजकीयम्, "अल्लोपोऽनः" इति प्राप्नोति ॥

(प्रत्याख्यातृसमाधानभाष्यम्)

एकदेशविकृतमनन्यवत् षष्ठीनिर्दिष्टस्य ॥

(प्रदीपः) षष्ठीनिर्दिष्टस्येति । 'राज्ञः क च' इत्यत्र राजन्शब्दः षष्ठीनिर्दिष्टः, न तु 'अन्'-इति लोपाभावः ॥

(उद्द्योतः) सिद्धान्त्येकदेशी वार्तिं दृष्ट्वा स्थानिवत्सूत्रगतेनोपन्यस्तमित्याशयेनाह—षष्ठीनिर्दिष्टस्येति ॥ तत्संबन्ध्येकदेशविकृतमादेशरूपमित्यर्थः ॥ ननु 'अल्लोपोऽनः' इत्यत्र 'अन्' अपि षष्ठीनिर्दिष्ट एवेत्यत आह—राज्ञ इति । येन विकारेण यस्य विकृतस्य यद्रूपमेकदेशविकृतन्यायेन प्रार्थ्यते तद्रूपावच्छिन्नस्य तेन रूपेण तद्विकारविधौ षष्ठीनिर्दिष्टत्व-इति तदर्थ इति भावः ॥

(प्रयोजनवादिभाष्यम्)

यदि—षष्ठीनिर्दिष्टस्येत्युच्यते, 'क्लृप्तशिख' इति प्लुतो न प्राप्नोति । न ह्यत्र ऋकारः षष्ठीनिर्दिष्टः ॥

कस्तर्हि ?

रेफः ॥

(प्रदीपः) यद्येवं 'कृपो रो लः' इत्यत्रापि ऋकारः षष्ठ्या न निर्दिष्ट इत्यनन्यत्वं न प्राप्नोतीत्याह—यदीति ॥

(उद्द्योतः) भाष्ये—प्लुतो न प्राप्नोतीति । द्विर्वचनादेरप्युपलक्षणम् ॥ कस्तर्हि रेफ इति । 'कृपः' इति त्ववयवषष्ठीति भावः ॥

(प्रत्याख्यातृभाष्यम्)

ऋकारोऽप्यत्र षष्ठीनिर्दिष्टः ॥

कथम् ?

अविभक्तिको निर्देशः—कृप-उः-रः-लः-"कृपो रो लः" इति ॥

(उद्द्योतः) कृप उरिति ॥ कृपे रेफस्य लः, तदवयवऋकारस्य च लकारघटित आदेश इत्यर्थः । स्थानिनिर्देश एव तादृशादेशकल्पक इति भावः ॥ एतेन तस्यावयवषष्ठ्यन्तत्वेन स्थानषष्ठीनिर्दिष्टत्वाभावादिदं चिन्त्यमित्यपास्तम् ॥

(प्रत्याख्यातुरेव भाष्यम्)

अथवा पुनरस्तु अविशेषेण ॥

(प्रदीपः) अथवेति । 'षष्ठीनिर्दिष्टस्य' इति नापेक्ष्यते ॥

(उद्द्योतः) ननु स्थानिवत्सूत्रे हि तथा । प्रकृते च न तेनातिदेश उच्यते, किं तु छिन्नपुच्छश्वदृष्टान्तेन प्रत्यभिज्ञयाऽनन्यत्वमुच्यते । तत्र 'षष्ठीनिर्दिष्टस्य' इति वक्तुमेवाशक्यमित्याशयेनाह भाष्ये—अथवेति ॥

(आक्षेपकारणभाष्यम्)

ननु चोक्तं–"राज्ञः क च" राजकीयम् "अल्लोपोऽनः" इति प्राप्नोतीति ॥

(आक्षेपबाधकभाष्यम्)

नैष दोषः । वक्ष्यत्येतत्—"* श्वादीनां संप्रसारणे नकारान्तग्रहणमनकारान्तप्रतिषेधार्थम् *" इति । तत्प्रकृतमुत्तरत्रानुवर्तिष्यते—"अल्लोपोऽनः" नकारान्तस्येति ।

(प्रदीपः) नकारान्तस्येति । न च राजन्शब्दः कादेशे कृते नकारान्तो भवति, श्वेव पुच्छे छिन्ने न पुच्छवानिति भावः ॥

(उद्द्योतः) ननु कादेशेऽनत्वमिवैकदेशविकृतन्यायेन नकारान्तत्वमपि कुतो नेत्यत आह—न च राजन्निति । एकदेशपदेन ससम्बन्धिकतयोपस्थितावयविधर्म एव विकारविशिष्टे आरोप्यते, न त्ववयव एव, लोकव्यवहारादिति भावः ॥

(प्रयोजनबाधाक्षेपभाष्यम्)

इह तर्हि क्लृप्तशिख "अनृतः" इति प्रतिषेधः प्राप्नोति ॥

(उद्द्योतः) भाष्ये—इह तर्हीति । एकदेशविकृतन्यायेन ऋत्वादिति भावः ॥

(३७ प्रत्याख्यातृसमाधानवार्तिकम् ॥ ५ ॥)

॥ * ॥ रवत्प्रतिषेधाच्च ॥ * ॥

(भाष्यम्)

रवत्प्रतिषेधाच्चैतत्सिध्यति । "गुरोररवतः" इति वक्ष्यामि ॥

(प्रदीपः) अरवत इति । रोऽस्यास्ति नित्यमिति नित्ययोगे मतुप् । तेन ऋकार एव रवान्, न तु वर्तक इत्यादावकारः । न रवान्-अरवानिति समासः । नित्ययोगप्रतिपादनाय बहुव्रीहिर्न कृतः—'गुरोररस्य' इति ॥

(उद्द्योतः) रोऽस्यास्तीति । इदं चिन्त्यम्—अवयवादेव मत्वर्थो नानन्तरादाविति वर्तक इत्यादौ रवत्त्वस्योपपादयितुमशक्यत्वान्नित्ययोगपर्यन्तधावनमफलमिति ॥

(आक्षेपभाष्यम्)

यदि 'अरवतः' इत्युच्यते, होतृ-ऋँकारः-'होतॄकारः' अत्र न प्राप्नोति ॥

(आक्षेपबाधकभाष्यम्)

"गुरोररवतो ह्रस्वस्य" इति वक्ष्यामि ॥

(प्रदीपः) ह्रस्वस्येति । तेन ह्रस्वस्यैव रवतः प्लुतनिषेधः, न दीर्घस्य ॥

(सिद्धान्तिभाष्यम्)

स एष सूत्रभेदेन लकारोपदेशः प्लुत्याद्यर्थः सन्प्रत्याख्यायते । सैषा महतो वंशस्तम्बाल्लट्वाऽनुकृष्यते ॥ २ ॥

(प्रदीपः) वार्तिककारस्य लृकारप्रत्याख्यानं निःप्रयोजनमित्याह—सैषेति ॥ २ ॥

(उद्द्योतः) भाष्ये—स एष इति । प्लुत्याद्यर्थं विद्यमानलकारोपदेशः 'अरवतो ह्रस्वस्य' इति गुरुन्यासरूपसूत्रभेदेन प्रत्याख्यायत इति यत्तदयुक्तमित्यर्थः ॥ कुत इत्यत आह—सैषेति । यतः सैषा प्रत्याख्यानात्मिका उक्तिर्महतो वंशस्तम्बाल्लट्वानुकर्षणमिवा–इत्युक्ते यथा महतो वंशस्तम्बाल्लट्वानुकर्षणमयुक्तम्, एवं–लकारप्रत्याख्यानमिति गम्यते । तदाह—निष्प्रयोजनमिति । सूत्रभेदपरिकल्पनं विना क्लृप्तशिखे प्लुतसाधनस्याशक्यत्वान्निष्प्रयोजनमित्यर्थः ॥ वंशस्तम्बादिति–ल्यब्लोपे पञ्चमी । तमवलम्ब्येत्यर्थः । लट्वा–पक्षिविशेषः फलविशेषो वा । तथा–बह्वायाससाध्यमल्पफलं न युक्तं, तथा लकारोपदेशप्रत्याख्यानमपीत्यर्थं इति दिक् ॥ २ ॥

(शिवसूत्रे)

एओङ् ॥ ३ ॥ ऐऔच् ॥ ४ ॥

(अतपरत्वव्यवस्थाधिकरणम्)

(वार्तिकावतरणभाष्यम्)

इदं विचार्यते—'इमानि संध्यक्षराणि तपराणि वोपदिश्येरन् 'एत्-ओत्-ङ्' 'ऐत्-औत्-च्' इति, अतपराणि वा यथान्यासम्' इति ॥

(प्रदीपः) एओङ् ॥ ऐऔच् ॥ इदं विचार्यत इति । तपरातपरसन्ध्यक्षरोपदेशो विचार्यत इत्यर्थः ॥ तत्र 'उपदिश्येरन्' इत्यत्रासत्त्वभूता यद्यपि क्रियाऽभिधीयते, तथापि बुद्ध्या परामृष्टा सत्त्वरूपतामापादिता विचारक्रियायां कर्मभावमनुभवति । यथा पश्य मृगो धावतीति सरणं दर्शने ॥

(उद्योतः) एओङ् ॥ ३ ॥ ऐऔच् ॥ ४ ॥ विचार्यत इति। कृत्वाचिन्तान्यायेनायं विचार इति बोध्यम् ॥ 'इदं'पदार्थमाह—तपरेति। असत्त्वभूतेति। एवं चेदमा परामर्शोऽनुपपन्न इति भावः ॥ बुद्ध्या परामृष्टेति। व्यपदेशपदार्थभूतेत्यर्थः ॥ कर्मभावमिति। इदंपदवाच्यत्वेनेति भावः ॥ यथेति। इदं चिन्त्यम्। कर्तृकर्मेतरकारकाभाववत्त्वस्यैवासत्त्वपदार्थत्वात् ॥

(भाष्यम्)

कश्चात्र विशेषः?

(प्रदीपः) **कश्चात्रेति**। कार्ये को विशेष इति **प्रश्नः** ॥

(उद्योतः) पक्षद्वये स्वरूपवैलक्षण्यस्यानुभवसिद्धत्वेन तद्विषयः प्रश्नोऽनुचितोऽत आह—कार्ये इति ॥

(३८ तपरपक्षदूषणवार्तिकम् ॥ १ ॥)

॥ * ॥ संध्यक्षरेषु तपरोपदेशश्चेत्तपरोच्चारणम् ॥ * ॥

(भाष्यम्)

संध्यक्षरेषु तपरोपदेशश्चेत्तपरोच्चारणं कर्तव्यम् ॥

(प्रदीपः) **तपरोपदेशश्चेदिति**। यद्यप्युपदेशः=उच्चारणं, तथापि तपरोपदेशे फलं चेदस्ति ततस्तकारोच्चारणं कर्तव्यमित्यर्थः। **'संध्यक्षराणि'**इत्यन्वर्था पूर्वाचार्यसंज्ञा, संधीयमानावयवत्वात् ॥

(उद्योतः) भेदाभावादुद्देश्यविधेयभावोऽनुपपन्न इत्याशङ्क्य परिहरति—यद्यपीत्यादि ॥ फलं चेदिति। संप्रदाने घञिति भावः ॥ फलस्यैव करणत्वविवक्षया करणे घञित्यन्ये ॥ सन्धीयमानावयवत्वादिति। 'अइउण्' इति शिष्यमाणवर्णसदृशावयवसन्धानेनास्य निष्पन्नत्वादित्यर्थः ॥

(३९ तपरत्वपक्षदूषणवार्तिकम् ॥ २ ॥)

॥ * ॥ प्लुत्यादिष्वज्विधिः ॥ * ॥

(भाष्यम्)

प्लुत्यादिष्वजाश्रयो विधिर्न सिध्यति ॥ 'गो३त्रात' 'नौ४त्रात' इत्यत्र "अनचि च" (८।४।४७) अच उत्तरस्य यरो द्वे भवत इति द्विर्वचनं न प्राप्नोति। इह च 'प्रत्यङ्कै४तिकायन' 'उदङ्कौ४पगव' इति 'अचि' इति ङमुण्न प्राप्नोति ॥

(प्रदीपः) **प्लुत्यादिष्विति**। प्लुतसंज्ञामभ्युपगम्याच्कार्याणि न सिध्यन्तीत्युच्यते ॥

(उद्योतः) भाष्ये—प्लुतिग्रहणं त्रिमात्रपरम्। आदिना चतुर्मात्रग्रहणम् ॥

(४० तपरत्वपक्षदूषणवार्तिकम् ॥ ३ ॥)

॥ * ॥ प्लुतसंज्ञा च ॥ * ॥

(भाष्यम्)

प्लुतसंज्ञा च न सिध्यति ॥ 'ऐ३तिकायन' 'औ३पगव' ऊकालोऽज्झ्रस्वदीर्घप्लुतसंज्ञो भवतीति प्लुतसंज्ञा न प्राप्नोति ॥

(प्रदीपः) प्लुत एव न प्राप्नोतीति दर्शयितुमाह—**प्लुतसंज्ञा चेति**। त्रिमात्रस्याचः प्लुतसंज्ञा विधीयते, तपरत्वे च त्रिमात्रस्याग्रहणादच्त्वाभावः। तत्रैचां प्लुतो विधीयमान इकारोकाराभ्यां गृहीत ईकार ऊकारश्च स्यात्।

(उद्योतः) ननु 'ओमभ्यादाने' इत्यादिनाऽन्तरतमपरिभाषासंस्कृतेनैज्रूपप्लुतविधानादनच्त्वेऽपि तेषां प्लुतसंज्ञा भविष्यतीत्यत आह—तत्रैचामिति। ताभ्यामपि तेषां यथाकथंचिदान्तरतम्यसत्त्वादिति भावः ॥

(अतपरपक्षाभ्युपगमभाष्यम्)

सन्तु तर्ह्यतपराणि ॥

(४१ अतपरपक्षदूषणवार्तिकम् ॥ ४ ॥)

॥ * ॥ अतपर एच इग्घ्रस्वादेशे ॥ * ॥

(भाष्यम्)

यद्यतपराणि "एच इग्घ्रस्वादेशे" इति वक्तव्यम् ॥ किं प्रयोजनम्? ॥ एचो ह्रस्वादेशशासनेषु अर्ध एकारः-अर्ध ओकारो वा मा भूदिति ॥

(प्रदीपः) **अतपर इति**। असति हि तपरत्वे एकारौकाराभ्यां मात्रिकयोरर्धैकारार्धौकारयोर्ग्रहणादच्त्वाद्ध्रस्वत्वाद्विधानं स्यादिति सूत्रं कर्तव्यम्। तपरत्वे तु तयोरग्रहणात्प्राप्त्यभावः ॥

(उद्योतः) भाष्ये—अर्ध एकार इति। मात्रिकत्वेनार्धत्वम्। समांशवाचिनोऽपि पुंस्त्वमेतद्भाष्यप्रामाण्यात् ॥

(अतपरवादिनः शङ्काभाष्यम्)

ननु च यस्यापि तपराणि, तेनाप्येतद्वक्तव्यम्। इमावैचौ समाहारवर्णौ—मात्राऽवर्णस्य, मात्रेवर्णोवर्णयोः। तयोर्ह्रस्वादेशशासनेषु कदाचिदवर्णः स्यात्, कदाचिदिवर्णोवर्णौ; मा कदाचिदवर्णो भूदिति ॥

(प्रदीपः) **ननु चेति**। सूत्रारम्भं प्रति न कश्चिद्विशेष इत्यर्थः। अतपरत्वे 'एचः' इति वक्तव्यं, तपरत्वे तु 'ऐचः' इति। ऐचोर्विश्लिष्टावर्णत्वात्संश्लिष्टावर्णावर्धैकारार्धौकारौ न भवतः ॥

(उद्योतः) भाष्ये—तेनाप्येतद्वक्तव्यम्–इत्यत्र एतच्छब्देन नियामकं सूत्रं परामृश्यते ॥ सूत्रन्यासभेदेऽपि गुरुलाघवतो विशेषो नास्तीत्याह—सूत्रारम्भं प्रतीति ॥ विश्लिष्टेति। उपलभ्यमानेत्यर्थः ॥ संश्लिष्टेति। स्पष्टमनुपलभ्यमानेत्यर्थः। एवञ्च–एङ्विषये नावर्णप्राप्तिः। अर्धैङोस्तु तपरनिर्देशेऽनच्त्वात् ह्रस्वत्वमेव नेति भावः ॥ एङोः शुद्धताल्व्यत्वमेवेति न तयोः स्थानेऽवर्णप्राप्तिरिति तत्त्वम् ॥ 'संश्लिष्टावर्णौ' इति कैयटस्याप्यत्रैव तात्पर्यम् ॥

(तपरवादिन उत्तरभाष्यम्)

प्रत्याख्यायत एतत्, "*ऐचोश्चोत्तरभूयस्त्वात्*" (१।१।४८) इति ॥

(प्रदीपः) **ऐचोश्चेति** । अर्धमात्राऽवर्णस्य-अध्यर्धमात्रा इवर्णोवर्णयोः, भूयसा च व्यपदेशो मल्लग्रामवदितीकारोकारावेव भविष्यतः ॥

(उद्द्योतः) भाष्ये-प्रत्याख्यायत एतदिति । एतत्-ऐज्विषयं 'एच इक्' इति सूत्रम् । वर्तमानसामीप्ये लट् ॥ भूयसा चेति । तद्वारकभूयःस्थानसाम्यादित्यर्थः ॥

(अतपरवादिन उत्तरभाष्यम्)

यदि प्रत्याख्यानपक्षः, इदमपि प्रत्याख्यायते । "*सिद्धमेङः सस्थानत्वात्*" (१।१।४८) इति ॥

(प्रदीपः) **सिद्धमेङ इति** । अर्धैकारार्धौकारौ न स्तः, तत्र तालव्य एकारः–ओष्ठ्य ओकारः–इति तयोः स्थान इकारोकारावेव भविष्यतः ॥

(उद्द्योतः) भाष्ये-इदमपीति । एङ्विषयमपीत्यर्थः ॥ सस्थानत्वादिति । इकारोकाराभ्यां समानस्थानत्वादित्यर्थः । तदाह—तालव्य इति । तालव्य एवेत्यर्थः ॥ [इदं च मतमष्टमेऽपि भाष्ये स्पष्टम् ॥ शब्दपरविप्रतिषेधेनोत्तरभागस्थूरा इति विवरणोक्तं तु चिन्त्यम् । अन्तरङ्गत्वेन पूर्वसवर्णस्यैवापत्तेः । स्पष्टं चेदं 'नित्यः परयणादेशः' इत्यादिना 'अचः परस्मिन्—' इत्यत्र भाष्ये ॥]

(आक्षेपभाष्यम्)

ननु चैङः सस्थानतरावर्ध एकारोऽर्ध ओकारः ॥

(समाधानभाष्यम्)

न तौ स्तः । यदि हि तौ स्यातां तावेवायमुपदिशेत् ॥

(प्रदीपः) **तावेवेति** । ताभ्यामुपदिष्टाभ्यां दीर्घप्लुतयोरपि ग्रहणं सिध्यतीति भावः । गुणसंज्ञायां तु दीर्घावेकारौकारौ निर्देश्यौ ॥

(उद्द्योतः) भाष्ये—तावेवेति । लाघवादिति भावः ॥ ग्रहणमिति । प्रदेशेषु इति शेषः ॥ नन्वेवं मात्रिकयोरेव गुणसंज्ञास्यादत आह—गुणेति । एवमपि अत्र ह्रस्वपाठेऽर्धमात्रालाघवं भवति ॥

(आक्षेपभाष्यम्)

ननु च भोश्छन्दोगानां सात्यमुग्रिराणायनीया अर्धमेकारमर्धमोकारं चाधीयते—सुजाते एश्वसूनृते, अध्वर्यो ओद्रिभिः सुतम्, शुक्रं ते एन्यद्यजतं ते एन्यत्—इति ॥

(प्रदीपः) **सुजात इति** । अन्तःपादस्थस्याप्यपरस्याकारस्यार्धमेकारमर्धमोकारं च विदधाति ॥

(उद्द्योतः) अकारस्यार्धमिति । सुजाते ए अश्व इति अकारलेखस्तु प्रामादिकः ॥

(समाधानभाष्यम्)

पार्षदकृतिरेषा तत्रभवताम् । नैव हि लोके नान्यस्मिन्वेदेऽर्ध एकारोऽर्ध ओकारोऽस्ति ॥

(प्रदीपः) **पार्षदकृतिरिति** । गीतिविशेषार्थतयोच्चारणमित्यर्थः ॥

(उद्द्योतः) शाखाविशेषाध्यायिनां समवायः—परिषद्, पर्षद्वा । तत्र भवा कृतिरित्यर्थः ॥

(४२ अतपरपक्षदूषणवार्तिकम् ॥ ५ ॥)

॥ * ॥ एकादेशे दीर्घग्रहणम् ॥ * ॥

(भाष्यम्)

एकादेशे दीर्घग्रहणं कर्तव्यम्—"आद्गुणः" दीर्घः, "वृद्धिरेचि" दीर्घः-इति ॥

किं प्रयोजनम् ?

आन्तर्यतस्त्रिमात्रचतुर्मात्राणां स्थानिनां त्रिमात्रचतुर्मात्रा मा भूवन्निति । खट्वा-इन्द्रः-खट्वेन्द्रः, खट्वा-उदकं-खट्वोदकं, खट्वा-ईषा-खट्वेषा, खट्वा-ऊढा-खट्वोढा, खट्वा-एलका-खट्वैलका, खट्वा-ओदनः-खट्वौदनः, खट्वा-ऐतिकायनः-खट्वैतिकायनः, खट्वा-औपगवः-खट्वौपगव इति ॥

(प्रदीपः) **आन्तर्यत इति** । अन्यस्यासम्भवादिदमत्र नास्ति—प्लुतश्च विषये स्मृतः–इति ॥

(उद्द्योतः) तदेवमतपर-तपरवादिमतसाधारण्येन 'एच इक्' इति सूत्रस्य कर्तव्यताकर्तव्यते उपपाद्यातपरवादिमतेऽसाधारणं दूषणमाह—भाष्ये-एकादेशे इति । 'एकः पूर्वपरयोर्दीर्घः' इति सूत्रं कार्यमित्यर्थः ॥

अन्यस्यासंभवादिति । अयं भावः—यथा 'स्थाघ्वोः' इत्यत्रातपरत्वे स्थाघ्वोर्दीर्घस्य स्थाने 'घुमास्था–' इत्येव दीर्घेकारे सिद्धे पुनर्वचनमदीर्घार्थमित्यविशेषात् ह्रस्वप्लुतयोः प्रसङ्गे तदुक्तं–प्लुतश्च विषये–इति । एवं च दूराद्धूतादिविषयेऽप्यनेनैव प्लुते पक्षेऽनुवाददोषस्तत्र, इह तु प्लुत एव प्राप्नोतीति 'खट्वा-इन्द्रः' इत्यादिविषयकशास्त्रवैयर्थ्यमेवेत्यनुवाददोषः सोऽत्र्य एवेति वैषम्यमिति ॥ वस्तुतोऽस्य टित्त्वाभावादेतद्विषये प्लुताप्रवृत्तेश्चिन्त्यमेवेदमिति 'स्थाघ्वोः' इति सूत्रे निरूपयिष्यामः ॥

(आक्षेपभाष्यम्)

तर्हि दीर्घग्रहणं कर्तव्यम् ॥

(समाधानभाष्यम्)

न कर्तव्यम् । उपरिष्टाद्योगविभागः करिष्यते—"अकः सवर्णे" एको भवति ॥ ततः—"दीर्घः" दीर्घश्च स भवति, यः स 'एकः पूर्वपरयोः' इत्येवं निर्दिष्ट इति ॥

(उद्द्योतः) भाष्ये—यः स इति । प्रसिद्ध्यर्थकम् ॥

(दीर्घग्रहणाक्षेपभाष्यम्)

इहापि तर्हि प्राप्नोति—पशुं, विद्धं, पचन्ति–इति ॥

(समाधानभाष्यम्)

नैष दोषः । इह तावत्–पशुमिति "अमि" एक

इतीयता सिद्धम् । सोऽयमेवं सिद्धे सति यत्पूर्वग्रहणं तस्यैतत्प्रयोजनम्—यथाजातीयकः पूर्वस्तथाजातीयक उभयोर्यथा स्यात्-इति ॥

विद्धमिति 'पूर्वः' इत्येवानुवर्तते ॥ अथवा-आचार्यप्रवृत्तिर्ज्ञापयति—नानेन संप्रसारणदीर्घो भवतीति, यदयं हल उत्तरस्य संप्रसारणस्य दीर्घत्वं शास्ति ॥

पचन्तीति "अतो गुणे" पर इतीयता सिद्धम् । सोऽयमेवं सिद्धे सति यद्रूपग्रहणं करोति, तस्यैतत्प्रयोजनम्—यथाजातीयकं परस्य रूपं तथाजातीयकमुभयोर्यथा स्यात्-इति ॥

(प्रदीपः) अम्येक इति । 'प्रथमयोः-' इति सिद्ध एतदपि किमर्थमुच्यते-इति चेत्, 'वा छन्दसि' इति अत्रानुवृत्त्यर्थम् । तस्मात् पूर्वश्रुतिः पूर्वरूपार्था, सैव चोत्तरत्रानुवर्तत इति 'विद्धं' इति पूर्वरूपं भविष्यति ॥

अथवेति । 'विधिनियमसंभवे विधिरेव बलीयान्' इति विधेर्बलीयस्त्वान्नियमो न भवति-हल एव दीर्घत्वं यथा स्यात्, उतमित्यादौ मा भूदिति ॥

(उद्द्योतः) वा छन्दसीत्यत्रेति । 'वा छन्दसि' इत्यस्यात्रानुवृत्त्यर्थमित्यर्थः ॥ पूर्वरूपार्थेति । पूर्वव्यक्त्यात्मकपूर्वरूपार्थेत्यर्थः ॥ भाष्ये—पर इतीयतेति । हस्वत्वादिरूपमिति भावः ॥ सिद्धान्ते तु रूपग्रहणं स्पष्टार्थमेव, अस्य भाष्यस्य पूर्वपक्ष्युक्तित्वात् ॥

(दीर्घग्रहणाक्षेपभाष्यम्)

इह तर्हि-खट्वर्श्यो मालर्श्य इति । दीर्घवचनादकारो न, अनान्तर्यादिकारौकारौ न ॥

तत्र को दोषः ?

विगृहीतस्य श्रवणं प्रसज्येत ॥

(उद्द्योतः) अकारो नेति । रपरत्वेऽपि द्विमात्रत्वरूपदीर्घत्वासंभव एव ॥ विगृहीतस्येति । दीर्घश्रुति-परिभाषयोर्विरोधेन जातिपक्षे व्यक्तिपक्षे वा तद्विषयकलक्षणानुपपत्तेरिति भावः ॥

(वार्तिकैकदेशिनः समाधानभाष्यम्)

न ब्रूमः—यत्र क्रियमाणे दोषस्तत्र कर्तव्यमिति ॥

किं तर्हि ?

यत्र क्रियमाणे न दोषस्तत्र कर्तव्यम्—इति ।

(आक्षेपभाष्यम्)

क्व च क्रियमाणे न दोषः ?

(समाधानभाष्यम्)

संज्ञाविधौ । वृद्धिरादैज् दीर्घः, अदेङ् गुणो दीर्घ इति ॥

(आक्षेपभाष्यम्)

तत्तर्हि दीर्घग्रहणं कर्तव्यम् ॥

(सिद्धान्तिसमाधानभाष्यम्)

न कर्तव्यम् ॥

कस्मादेवान्तर्यतस्त्रिमात्रचतुर्मात्राणां स्थानिनां त्रिमात्रचतुर्मात्रा आदेशा न भवन्ति ?

तपरे गुणवृद्धी ॥

(प्रदीपः) तपरे इति । तपरसंज्ञिसहचरिते गुणवृद्धिसंज्ञे इत्यर्थः ।

(उद्द्योतः) ननु गुणवृद्धिसंज्ञयोस्तपरत्वाभावात्पूर्वोक्तदोषापरिहृतेश्च भाष्यमयुक्तमित्याशङ्क्याह—तपरसंज्ञीति । तपरशब्दनिर्दिष्टे संज्ञिनि गुणवृद्धिसंज्ञे प्रवर्तेते इत्यर्थः । एवञ्च त्रिमात्रादीनां तत्र संज्ञितयाऽनिर्देशान्नोक्तदोष इति भावः ॥

(आक्षेपभाष्यम्)

ननु च तः परो यस्मात्सोऽयं-तपरः ॥

(उद्द्योतः) भाष्ये—ननु चेति । एवञ्च-एचैचौ न तपराविति भावः ॥

(समाधानभाष्यम्)

नेत्याह । तादपि परः—तपर इति ॥

(प्रदीपः) तादपीति । तत्रन्यायाश्रयणादेकस्यैव द्विशक्तित्वादेकशेषाश्रयणाद्वाऽनेकार्थाभिधानमिति भावः ॥

(उद्द्योतः) नेत्याहेति । स एव तपर इति न-इत्याहेत्यर्थः ॥ अर्थभेदेन शब्दभेदे—तन्त्रन्यायेति ॥ तद्भेदेऽपि शब्दैक्यपक्षे आह—एकस्यैव द्विशक्तित्वादिति ॥ एकशेषेति । समाहारद्वन्द्वविषये एकशेषाभावेनैकवचनानुपपत्त्येदं चिन्त्यम् ॥

(आक्षेपभाष्यम्)

यदि तादपि परस्तपरः "ऋदोरप्" इतीहैव स्यात् यवः स्तवः । लवः पव इत्यत्र न स्यात् ॥

(समाधानभाष्यम्)

नैष तकारः ॥

कस्तर्हि ?

दकारः ॥

(आक्षेपभाष्यम्)

किं दकारे प्रयोजनम् ?

(प्रदीपः) बहुव्रीहिवादी चोदयति—किं दकार इति ॥

(प्रतिबन्दिसमाधानभाष्यम्)

अथ किं तकारे ?

यद्यसंदेहार्थस्तकारः, दकारोऽपि । अथ मुखसुखार्थस्तकारः, तर्हि दकारोऽपि ॥

(प्रदीपः) समासद्वयवादी तं प्रत्याह—अथ किं तकार इति । तव केवलबहुव्रीहिवादिनो निःप्रयोजनं तपरत्वम्, ऋकारस्यानण्त्वात् भिन्नकालानां ग्रहणाप्रसङ्गात्, गुणानां चाभेदकत्वात् प्राप्त्यर्थाभावात् । अथ तवासन्देहार्थौ वा मुखसुखार्थौ वा तकारः, एवं मम दकार इत्यर्थः ॥ 'तित्स्वरितम्' इत्यत्र भाष्येणास्य विरोधः । तत्र हि-तिदिति प्रत्ययग्रहणं चोदितम्, इह मा भूत्-'दिव उत्' द्युभ्यामिति, ततो विस्पष्टार्थेन प्रत्याख्यातम्, तपरसूत्रे न दकारश्चर्त्वभूतो निर्दिश्यते ।

तेन तत्कालस्य ग्राहको दकारः—इत्युक्तम् । इह च दकाराभ्युपगमेन लवादिदोषः परिहृतः ॥ अत्राहुः—धकारस्थानिको धकारस्थानिको वा दकारोऽत्र विवक्षितः—'कस्तर्हि, दकारः' इति ॥

(उद्द्योतः) (भाष्ये) 'सुखमुखार्थः' इति पाठे मयूरव्यंसकादित्वात्समासः ॥ ननु एङैजिति संज्ञायास्तात्परत्वेऽपि संज्ञिनामेकारादीनां किमागतमिति चेत्, न । तपरशब्दबोध्योऽपि वर्णस्तत्कालस्यैव संज्ञा—इत्यर्थान्न दोषः ॥ गुणानां चेति । अणुस्तु गुणानां तत्त्वाभावेऽपि अनण्त्वादेः दीर्घादिविषये तत्त्वमिति भावः ॥ ननु दिव्ते 'दिव उत्' इत्यत्र तत्कालग्रहणं न स्यादत आह—तपरसूत्रे चेति ॥ इहेति । तपरसूत्रे दकारानाश्रयणेन चेत्यपि बोध्यम् ॥ थकारस्थानिक इति । तस्य चैतद्दृष्ट्याऽसिद्धत्वान्न तत्र तपरसूत्रप्रवृत्तिरिति भावः ॥

(इति अतपरत्वव्यवस्थानिर्णयः ॥)

(अथ वर्णैकदेशग्रहणाग्रहणनिर्णयाधिकरणम्)

(पक्षद्वयोपस्थापकभाष्यम्)

इदं विचार्यते—य एते वर्णेषु वर्णैकदेशा वर्णान्तरसमानाकृतयः, एतेषामवयवग्रहणेन ग्रहणं स्याद्वा न वा—इति ॥

कुतः पुनरियं विचारणा ?

इह समुदाया अप्युपदिश्यन्ते, अवयवा अपि ॥

अभ्यन्तरश्च समुदायेऽवयवः, तद्यथा—वृक्षः प्रचलन् सहावयवैः प्रचलति ।

तत्र समुदायस्थस्यावयवस्यावयवग्रहणेन ग्रहणं स्याद्वा न वा—इति जायते विचारणा ॥

कश्चात्र विशेषः ?

(प्रदीपः) **वर्णान्तरसमानाकृतय इति** । आकारादिष्वकारादिसदृशा अवयवाः, ऋकारऌकारयो रेफलकारसदृशावयवौ, संध्यक्षरेष्वकारेकारोकारसदृशाः; तत्र केवलवर्णकार्यमवयवेषु—भवति न वेति विचारः ॥ **इह समुदाया अपीति** । ऋ-ऌ-ए-ओ-ऐ-औ—इति ॥ **अवयवा अपीति** । अइउण्-ऋट्-लण्—इति ॥ तत्र समुदायपरे निर्देशे सन्निहिता अप्यवयवा नाऽपृथक्त्वादेजादिसंज्ञां न लभन्ते, अवयवपरे च निर्देशे समुदायो न संज्ञाभाक् । यथा—**हयवरे**त्यादावनच्कस्य हलो दुःखेनोच्चार्यत्वान्निर्दिष्टोऽप्यकारोऽन्यत्र प्राधान्येन निर्देशाद्धलादिसंज्ञां न प्रतिपद्यते—इति दध्यत्रेत्यादावनच्क एव यणादेशः प्रवर्तते । तत्रासत्यामप्येजादिसंज्ञायामयादयः समुदायादेशा अपि नान्तरीयकत्वादवयवान्निवर्तयन्ति । एवं स्थिते 'अग्ने-इन्द्र' इत्यादौ यत्रावयवकार्यं च प्राप्नोति समुदायकार्यं च, तत्रान्तरङ्गत्वात्तत्र च साक्षाच्चोदितत्वात्प्रत्यक्षत्वाच्चावयवकार्यप्रसङ्गः । अवयवावगतिपूर्वकत्वाद्धि समुदायावगमस्य समुदायकार्यं बहिरङ्गम् । अयादीनां त्ववकाशः—अग्न आयाहीति ॥ नन्वत्रापि यणादेशोऽवयवस्य प्राप्नोति । **येन नाप्राप्त** इति वा **मध्येऽपवादा** इति वा यण एवायादयो बाधकाः स्युः । तत्र यथा दधीन्द्र इत्यत्र दधिशब्दस्थ इकारः सवर्णदीर्घत्वं प्रतिपद्यते, एवमेकारस्थोऽपि प्रतिपद्येत । प्रत्याहारे **'एओङ्' 'ऐऔच्'** इत्यत्रावयवानां प्राधान्येनानिर्देशात्—इत्येवं **ग्रहणपक्षाशङ्काबीजमुपन्यस्तम्** ॥

इदानी**मग्रहणपक्षाशङ्काबीजमुपन्यस्यते—अभ्यन्तरश्चेति** । तिरोहितत्वादवयवानां समुदायकार्ये च पारतन्त्र्यात् स्वकार्यस्याप्रयोजकत्वान्नरसिंहवज्जात्यन्तरयोगाद्वर्णान्तरसारूप्यमात्रेण तत्कार्याप्रवर्तनादित्यर्थः ॥

(उद्द्योतः) **अवयवग्रहणेन**—अवयवसदृशवर्णग्रहणेन ग्रहणं स्यान्न वा—इति भाष्यार्थः । तत्फलितमाह—**तत्र केवलेति** ॥ नन्वकारेण एङवयवग्रहणसन्देहवत् अकारादीनामेङादिसंज्ञा प्राप्नोतीति विचारोऽपि कुतो नेत्यत आह—**तत्र समुदायेति** । अत एव प्राटीत्यादौ न पररूपम् ॥ तत्र दृष्टान्तमाह—**अवयवपरे चेति** । यथाऽवयवपरे निर्देशे समुदायो न संज्ञाभाक्, एवं समुदायपरे निर्देशेऽवयवा न तद्भाज इत्यर्थः । तदुपपादयति—**यथेति** ॥ **अन्यत्रेति** । सर्वस्यावयवस्यान्यत्र पृथङ्निर्देशे समुदायनिर्देशः स्वपर एव, सर्वस्यावयवस्यान्यत्रानिर्देशे तु समुदायनिर्देशोऽनिर्दिष्टावयवपर इति विवेकः ॥ नन्वेजादिसंज्ञानामवयवावृत्तित्वे कथमेचो निवर्तकेनायादिना तदवयवस्य निवृत्तिरत आह—**तत्रासत्यामपीति** । तन्निवृत्तिं विना समुदायनिवृत्तेः कर्तुमशक्यत्वादिति भावः ॥ **अवयवकार्यं**—दीर्घः ॥ **समुदायकार्यं**—अय् ॥ **तत्र च साक्षादिति** । दीर्घे । अयादिकार्ये हि समुदायव्यवधानेनावयवो नोदितः, न साक्षादिति भावः ॥ साक्षाच्चोदितत्वं प्रत्यक्षत्वे हेतुः ॥ नन्वयादिरनवकाशोऽत आह—**अयादीनामिति** ॥ **नन्विति** । ततश्च विध्यन्तरपूर्वकोऽयादिः सर्वस्य बाधकः स्यादिति भावः ॥ परिहरति—**येनेति** ॥ **प्राधान्येनानिर्देशादिति** । अस्यैजादिसंज्ञाभावेऽपि स्वतन्त्राकारेण ग्रहणं स्यादिति शेषः ॥

भाष्ये—**अभ्यन्तरश्चेति** । तदुच्चारणं विना समुदायोच्चारणस्याशक्यत्वादित्यर्थः ॥ तदाह—**तद्यथा वृक्ष इति** ॥ तदुपपादयति—**तिरोहितत्वादित्यादिना** ॥ **समुदायकार्ये पारतन्त्र्यादिति** । समुदायसंपादनरूपे कार्ये पारतन्त्र्यादित्यर्थः ॥ **स्वकार्यस्याप्रयोजकत्वादिति** । स्वकार्यनिरूपितप्रयोजकत्वाभावादित्यर्थः ॥ तत्प्रयोजकत्वाभावे हेतुः—**नरसिंहवदिति** । तदवयवे नरत्वाद्यभाववत् एतदवयवेऽप्यत्वाद्यभाव इति भावः ॥

(४२ ग्रहणपक्ष आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ वर्णैकदेशा वर्णग्रहणेन चेत्संध्यक्षरे समानाक्षरविधिप्रतिषेधः ॥ * ॥

(भाष्यम्)

वर्णैकदेशा वर्णग्रहणेन चेत्संध्यक्षरे समानाक्षराश्रयो विधिः प्राप्नोति, स प्रतिषेध्यः । अग्ने-इन्द्रम्, वायो-उदकम्, "अकः सवर्णे दीर्घः" इति दीर्घत्वं प्राप्नोति ॥

(प्रदीपः) **समानाक्षरेति** । समानशब्देन पूर्वाचार्यनिर्देशादकोऽभिधीयन्ते, **दश समाना** इति वचनात् । तेन समानकार्यं प्राप्नोतीत्यर्थः ॥

(उद्योतः) वचनादिति । अ आ इ ई उ ऊ ऋ ॠ ऌ ॡ दश समाना इति पूर्वव्याकरणवचनादित्यर्थः ॥ समानकार्यम्–अणूपसमानाक्षरकार्यमित्यर्थः । 'सवर्णकार्यं' इति पाठे सवर्णदीर्घरूपं कार्यमित्यर्थः ॥

(४३ आक्षेपान्तरवार्तिकम् ॥ २ ॥)

॥ * ॥ दीर्घे ह्रस्वविधिप्रतिषेधः ॥ * ॥

(भाष्यम्)

दीर्घे ह्रस्वाक्षराश्रयो विधिः प्राप्नोति, स प्रतिषेध्यः । आलूय प्रलूय–ह्रस्वस्य पिति कृति तुग्भवति–इति तुक् प्राप्नोति ॥

(आक्षेपबाधकभाष्यम्)

नैष दोषः, आचार्यप्रवृत्तिर्ज्ञापयति–'न दीर्घे ह्रस्वाश्रयो विधिर्भवति' इति । यदयं दीर्घाच्छे तुकं शास्ति ॥

(उद्योतः) भाष्ये—दीर्घाच्छे इति । दीर्घस्य छे तुगिति हि तदर्थः ॥ ननु 'ह्रस्वस्य' इत्यत्राच इत्येव सिद्धे ह्रस्वग्रहणसामर्थ्यादेव तुग्भेति चेत्, न । पदलाघवाभावादित्याशयात् ॥

(आक्षेपसाधकभाष्यम्)

नैतदस्ति ज्ञापकम् । अस्ति ह्यन्यदेतस्य वचने प्रयोजनम् ॥

किम् ?

"पदान्ताद्वा" इति विभाषां वक्ष्यामीति ॥

(उद्योतः) अस्ति हीति । तत्र 'दीर्घात्'इत्यस्याभावे कुठ्यच्छायेत्यादावपि विकल्पः स्यादिति भावः ॥

(आक्षेपबाधकभाष्यम्)

यत्तर्हि योगविभागं करोति । इतरथा हि "दीर्घात्पदान्ताद्वा" इत्येव ब्रूयात् ॥

(आक्षेपभाष्यम्)

इह तर्हि—खट्वाभिः, मालाभिः, अतो भिस ऐस्" इत्यैसभावः प्राप्नोति ॥

(आक्षेपबाधकभाष्यम्)

तपरकरणसामर्थ्यान्न भविष्यति ॥

(आक्षेपभाष्यम्)

इह तर्हि—याता, वाता, "अतो लोपः" आर्धधातुके–इत्यकारलोपः प्राप्नोति ॥

(आक्षेपबाधकभाष्यम्)

ननु चात्रापि तपरकरणसामर्थ्यादेव न भविष्यति ॥

(आक्षेपसाधकभाष्यम्)

अस्ति ह्यन्यत्तपरकरणे प्रयोजनम् ॥

किम् ?

सर्वस्य लोपो मा भूदिति ॥

(प्रयोजनबाधकभाष्यम्)

अथ क्रियमाणे तपरे परस्य लोपे कृते पूर्वस्य कस्मान्न भवति ?

(प्रयोजनसाधकभाष्यम्)

परलोपस्य स्थानिवद्भावादसिद्धत्वाच्च ॥

(प्रदीपः) असिद्धत्वाच्चेति । 'असिद्धवदत्राभात्' इत्यनेन ॥

(उद्योतः) असिद्धवदिति । चिणो लुङ्न्यायेनेति भावः ॥

(समाधानसाधकभाष्यम्)

एवं तर्ह्याचार्यप्रवृत्तिर्ज्ञापयति—'न आकारस्थस्य अकारस्य लोपो भवति' इति । यदयं "आतोऽनुपसर्गे कः" इति ककारमनुबन्धं करोति ॥

कथं कृत्वा ज्ञापकम् ?

कित्करणे एतत्प्रयोजनम्—कितीत्याकारलोपो यथा स्यादिति । यद्याकारस्थस्य केऽकारस्य लोपः स्यात्, कित्करणमनर्थकं स्यात् । परस्याकारस्य लोपे कृते द्वयोरकारयोः पररूपे हि सिद्धं रूपं स्यात्—गोदः, कम्बलद इति । पश्यति त्वाचार्यः—नाकारस्थस्य-अकारस्य लोपः स्यादिति, अतः ककारमनुबन्धं करोति ॥

(समाधानबाधकभाष्यम्)

नैतदस्ति ज्ञापकम् । उत्तरार्थमेतत्स्यात्–"तुन्दशोकयोः परिमृजापनुदोः" इति ॥

(उद्योतः) भाष्ये—उत्तरार्थमेतदिति । 'एह किंचित्त्रपो इति'इति न्यायस्तु नाश्रितः । अत्र केवलाकारोच्चारणे–उत्तरत्र ककाराकारयोरुच्चारणे गौरवादिति भावः ॥

(समाधानसाधकभाष्यम्)

यत्तर्हि "गापोष्टक्" इत्यनन्यार्थं ककारमनुबन्धं करोति ॥

(प्रदीपः) यत्तर्हीति । नन्वसति कित्त्वे आकारस्थस्याकारस्य लोपे कृते द्वयोरकारयोः पररूपस्य धातुं प्रत्यन्तवद्भावात् 'छन्दोगाय' इत्यत्र 'आतो धातोः' इत्याकारलोपप्रसङ्गः । नैष दोषः, सन्निपातपरिभाषया लोपो न भविष्यति । अकारं ह्याश्रित्य यशब्दः कृतो लोपस्यानिमित्तम् । दीर्घत्वं तु 'कष्टाय०' इति निपातनाद्भवति ॥

(उद्योतः) सन्निपातेति । न च दीर्घेणैव स निवर्तितः, दीर्घेऽप्यत्वजातिसंबन्धसत्त्वेन न तथा सन्निपातक्षतिः । लोपे तु तस्यापि निवृत्तेस्तद्विरोधस्य स्पष्टत्वादिति भावः ॥ परे तु जातिपक्षे [illegible] व्याप्यजातिनिर्देशस्यैव बोधकमिति यत्वनिमित्तसन्निपातस्य दीर्घेण निवृत्तिर्जातैव न कस्याप्यनुवृत्तिः, तस्माद्व्याप्यात्वजातियत्वादिसंनिपातनिमित्तो दीर्घो न स्वसंनिपातविघातकलोपनिमित्तम् । सन्निपातपरिभाषायाश्च स्वप्रवृत्तेः प्राक् स्वनिमित्तभूतो यादृशः संनिपातः स्वातिरिक्ततद्विघातकस्य स्वयमनिमित्तमित्यर्थः । मात्राकालिकत्वसमानाधिकरणव्यापकजातिनिर्देशपक्षेऽप्यङ्गसंज्ञा तद्धेनिमित्तं स्यादिति कुन्मेजन्तसूत्रवक्ष्यमाणभाष्यरीत्या यादेशनिमित्तसंनिपातस्य न लेशतोऽपि सत्तेति वदन्ति ॥ 'प्रातर्ॠतं-तत् ऌकारः' इत्यादौ 'रो रि' 'तोर्लि' इति तु नापादितं, तस्याभितोऽज्भागसत्त्वेन तेन व्यवधानात्तदप्राप्तेः ॥

(४४ आक्षेपवार्तिकम् ॥ ३ ॥)

॥ * ॥ एकवर्णवच्च ॥ * ॥

(भाष्यम्)

एकवर्णवच्च दीर्घो भवतीति वक्तव्यम् ॥

किं प्रयोजनम्?

वाचा तरतीति ह्यज्लक्षणष्ठन्मा भूदिति ।

इह वाचो निमित्तम्, "तस्य निमित्तं संयोगोत्पातौ" इति ह्यज्लक्षणो यन्मा भूदिति ॥

(प्रदीपः) **एकवर्णवदिति** । अवयवसंख्याश्रयणेन वाक्शब्दस्य ध्यच्त्वात्तन्निमित्तं कार्यं प्राप्नोतीति 'एकवर्णवत्' इत्यतिदेशः क्रियते ॥

(आक्षेपबाधकभाष्यम्)

अत्रापि गोनौग्रहणं ज्ञापकम्—'दीर्घे ह्यज्लक्षणो विधिर्न भवति' इति ॥

(प्रदीपः) **गोनौग्रहणं ज्ञापकमिति** । सामान्येन ज्ञापकं वर्णावयवाश्रयकार्याभावस्येति 'अग्न-एहि' इत्यादौ 'एङः पदान्तादति' इत्यादि न भवति ॥

(उद्योतः) 'अग्ने-इन्द्र' इत्यादौ सवर्णदीर्घव्यावृत्तये आह—**सामान्येनेति** । 'गोश्चचोऽसङ्ख्या-' इति गोग्रहणं, 'नौद्व्यचष्ठन्' इति नौग्रहणम् ॥ **वर्णावयवाश्रयकार्याभावस्येति** । वर्णावयवेषु-भेदेनाप्रतिभासमानेषु वर्णाश्रयकार्याभावस्येत्यर्थः । तेन मातणामित्यादौ णत्वादिसिद्धिः, भेदेन प्रतिभासात् ॥

(सर्वाक्षेपपरिहारभाष्यम्)

अयं तु सर्वेषामेव परिहारः—

(४५ समाधानवार्तिकम् ॥ ४ ॥)

॥ * ॥ नाव्यपवृक्तस्यावयवस्य तद्विधिर्यथा द्रव्येषु ॥ * ॥

(भाष्यम्)

नाव्यपवृक्तस्यावयवस्यावयवाश्रयो विधिर्भवति यथा द्रव्येषु । तद्यथा द्रव्येषु—"सप्तदश सामिधेन्यो भवन्ति" इति न सप्तदशारत्निमात्रं काष्ठमग्नावभ्याधीयते ॥

(प्रदीपः) **नाव्यपवृक्तस्येति** । व्यपवर्गः—व्यपवृक्तं=भेदः । तेनाव्यपवृक्तस्य—अभिन्नबुद्धिविषयस्य—एकत्वालम्बनज्ञानग्राह्यस्य समुदायस्य योऽवयवस्तस्मिंस्तद्विधिः—पृथग्भूतवर्णविधिर्न भवतीत्यर्थः । 'अव्यपवृक्तस्य-अवयवस्य' इति व्यधिकरणे षष्ठी, अव्यपवृक्तस्य समुदायस्य योऽवयवस्तस्येत्यर्थः । न हि संभवमात्रेण कार्याणि क्रियन्ते, अपि तु यत्र तद्बुद्धिरस्ति तत्रैवेत्यर्थः । **'माषा न भोक्तव्याः'** इति निषेधस्तु मिश्रेष्वपि वर्तते, तत्र तद्बुद्धितद्रसास्वादनसंभवात् ॥ **सप्तदशेति** । सामिधेनीशब्द ऋचां वाचकः साहचर्यात्काष्ठेषु वर्तते । तत्र सप्तदशहस्ते काष्ठे 'सप्तदश काष्ठानि' इति बुद्धेरभावान्न तस्याभ्याधानम् ॥

(उद्योतः) सामान्यापेक्षज्ञापकं विनाऽपि न्यायेन निर्वाहमाह—भाष्ये—**अयन्त्विति** । अभिन्नबुद्धिविषयस्येत्यस्य व्याख्या—**एकत्वालम्बनज्ञानग्राह्यस्येति** ॥ **समुदायस्य योऽवयव इति** । वर्णसमुदायस्येत्यर्थः ॥ **व्यधिकरणे इति** । सामानाधिकरण्येनान्वयेऽव्यपवृक्तस्येति व्यर्थं, सर्वस्याप्यवयवस्यावयविनाऽव्यपवृक्तत्वादिति भावः ॥ भाष्ये—**अवयवाश्रयः**=अवयवसङ्ख्यातवर्णाश्रयः ॥ उक्तेऽर्थे युक्तिमाह—**न हीति** ॥ ननु सामिधेनीशब्दस्य ऋक्षु शक्तत्वेन 'काष्ठमग्नावाधीयते' इति भाष्यमयुक्तमत आह—**साहचर्यादिति** । तदाधेयत्वेनेति भावः ॥ **तत्र सप्तदशेति** । यद्यपि एकैका समिदरत्निमात्रमिति मिलितानां सप्तदशानां समिधां सप्तदशारत्निमात्रत्वं भवति, एकस्यापि तावत्त्वमस्ति, तथाप्यव्यपवृक्तसमुदायावयवत्वान्न व्यपवृक्ताश्रयकार्यप्रसङ्ग इति भावः ॥

(दृष्टान्तवैषम्यभाष्यम्)

विषम उपन्यासः । प्रत्यृचं चैव हि तत्कर्म चोद्यते । असंभवश्चाग्नौ वेद्यां च ॥

(प्रदीपः) **असंभव इति** । अर्धचतुर्थहस्ता हि वेदिः ॥

(उद्योतः) न ह्यव्यपवृक्तत्वमात्रनिबन्धनं तदनभ्याधानं, किं तु असंभवनिबन्धनमित्याह—भाष्ये—**विषम इति** । आहितपुनर्ग्रहणस्य निषिद्धत्वादेकस्य काष्ठस्य प्रत्यृचमाधानं न संभवतीति भावः ॥ युक्त्यन्तरमाह—**असंभवश्चेति** ॥ तमुपपादयति—**अर्धचतुर्थहस्तेति** । अर्धेन चतुर्हस्तेति तृतीयातत्पुरुषः । सेमिधोऽग्निवेदिबहिर्भावनिषेधाच्चासंभव इति भावः ॥

(दृष्टान्तान्तरभाष्यम्)

यथा तर्हि—"सप्त प्रादेशमात्रीराश्वत्थीः समिधोऽभ्यादधीत" इति न सप्तदशप्रादेशमात्रं काष्ठमभ्याधीयते ॥

(प्रदीपः) **यथा तर्हीति** । अल्पप्रमाणत्वात्स्यात्संभव इत्यर्थः ॥

(दृष्टान्तवैषम्यभाष्यम्)

अत्रापि प्रतिप्रणवं चैतत्कर्म चोद्यते । तुल्यश्चासंभवोऽग्नौ वेद्यां च ॥

(सिद्धान्तिदृष्टान्तभाष्यम्)

यथा तर्हि—"तैलं न विक्रेतव्यम्" "घृतं न विक्रेतव्यम्" इति व्यपवृक्तं च न विक्रीयते । अव्यपवृक्तं—गावः सर्षपाश्च विक्रीयन्ते ।

तथा "लोमनखं स्पृष्ट्वा शौचं कर्तव्यम्" व्यपवृक्तं स्पृष्ट्वा नियोगतः शौचं कर्तव्यम्, अव्यपवृक्ते कामचारः ॥

(प्रदीपः) **अव्यपवृक्तमिति** । व्यपवर्गस्याभावेनेत्यर्थः ॥

(उद्योतः) **अव्यपवृक्तमिति** । अर्थाभावेऽव्ययीभावः ॥ तदाह—**व्यपवर्गस्येति** । वस्तुतस्तत्पुरुष एवायं, व्यपवृक्तभिन्नतैलमांसरूपा गावः सर्षपाश्चेत्यर्थः । नञोऽव्ययीभावस्याभावादित्यग्रे वक्ष्यते ॥ भाष्ये—**कामचार इति** । स्पर्शे कामचारः, तेन शौचाभाव इत्यर्थः ॥

(आक्षेपभाष्यम्)

यत्र तर्हि व्यपवर्गोऽस्ति ॥

क्व च व्यपवर्गोऽस्ति ?

सन्ध्यक्षरेषु ॥

(प्रदीपः) यत्र तर्हीति । 'ऐ–औ' इत्यत्र हि स्फुटोऽकारप्रतिभासोऽस्ति ॥

(उद्योतः) एङोः संश्लिष्टावर्णत्वेन व्यपवर्गस्यास्पष्टत्वात्सन्ध्यक्षरग्रहणमैजभिप्रायमित्याह—ऐ औ इति ॥

(समाधानभाष्यम्)

सन्ध्यक्षरेषु विवृतत्वात्

यदत्रावर्णं विवृततरं तदन्यस्मादवर्णात् । ये अपीवर्णोवर्णे विवृततरे ते अन्याभ्यामिवर्णोवर्णाभ्याम् ॥

(प्रदीपः) विवृतत्वादिति । अकारस्य विवृतोपदेशादत्र प्रकर्षो विवक्षितः, तदाह–'विवृततरं' इति । तत्र प्रयत्नभेदादसावर्ण्यादकारेण संध्यक्षरावयवस्य ग्रहणं नास्तीत्यर्थः । तदेवमाकारादिस्थस्यावयवस्य भेदेनाग्रहणादग्रहणम् । संध्यक्षरस्थस्य त्वसावर्ण्यात् । ऋकारस्थस्तु रेफो भेदेन प्रतिभासाद्दूष्यत इति नुडादिसिद्धिः ॥

(उद्योतः) अकारस्येति । यद्यप्यैचो विवृततमास्तथापि विवृततरत्वमस्त्येवेति भावः ॥ प्रयत्नभेदादेव एङैचोः परस्परं सावर्ण्याभावः । एङो विवृततरत्वात् ऐचां विवृततमत्वादिति बोध्यम् ॥ नुडादीति । 'आनृजे' इत्यत्र नुट् । आदिना 'चक्लृपे' इत्यत्र लत्वम्, 'मातॄणां' इत्यादौ णत्वं चेति बोध्यम् ॥

(अग्रहणपक्षाभ्युपगमभाष्यम्)

अथवा पुनर्न गृह्यन्ते ।

(प्रदीपः) अथवेति । नैरसिंहवद्वर्णान्तरत्वात्सादृश्याच्च प्रत्यभिज्ञानात्तत्त्वासिद्ध्या पृथगुपलब्धानां वर्णानां समुदाये नास्ति सत्त्वम् । समुदायवाचोयुक्तिरपि तत्र वर्णान्तरे न तात्त्विकी, भ्रान्तिवशात्त्ववयवसद्भावाश्रयेण प्रवृत्ता ॥

(उद्योतः) सादृश्याच्चेति । चस्त्वर्थे । समुदाये—सन्ध्यक्षरादौ ॥ सत्यपि गोसादृश्ये गवये गोत्वस्येव सन्ध्यक्षरावयवेषु अत्वादिजातेरभावादकारादिग्रहणेन ग्रहणं नेति भावः । ऐकारादीनामेकेच्छाप्रयत्नजन्यत्वेनैकत्वमेव, अकारादिवत् । अत एवैषां पदवन्न वर्णसमूहत्वेन प्रतिभास इति, तदेवाह—समुदायवाच इति ॥ भ्रान्तिवशादिति । भ्रान्तिगृहीतावयवसद्भावाश्रयेणेत्यर्थः । एवं च भ्रान्तिरेव ग्रहणपक्षबीजमिति भावः ॥ अत एव गोनौग्रहणं चरितार्थम् ॥

(४६ अग्रहणपक्षदूषणवार्तिकम् ॥ ५ ॥)

॥ * ॥ अग्रहणं चेन्नुड्विधिलादेशविनामेषु ऋकारग्रहणम् ॥ * ॥

(भाष्यम्)

अग्रहणं चेन्नुड्विधिलादेशविनामेषु ऋकारस्य ग्रहणं कर्तव्यम् । "तस्मान्नुड् द्विहलः" ऋकारे चेति वक्तव्यम्, इहापि यथा स्यात्—आनृधतुः, आनृधुरिति ।

यस्य पुनर्गृह्यन्ते 'द्विहलः' इत्येव तस्य सिद्धम् ॥

(उद्योतः) [वार्तिके] विनामः=णत्वम् ॥

(अग्रहणपक्षदूषणोद्धारभाष्यम्)

यस्यापि न गृह्यन्ते, तस्याप्येष न दोषः । द्विहल्ग्रहणं न करिष्यते । तस्मान्नुड् भवति—इत्येव ॥

यदि न क्रियते, आटतुः–आटुरित्यत्रापि प्राप्नोति ॥

अश्नोतिग्रहणं नियमार्थं भविष्यति—अश्नोतेरेवावर्णोपधस्य नान्यस्यावर्णोपधस्य—इति ॥

(प्रदीपः) अश्नोतेरेवेति । सामान्येनावर्णोपधो निवर्त्यते, न त्वश्नातिरेव; सामान्यापेक्षत्वान्नियमज्ञापकस्य ॥

(उद्योतः) ननु विकरणविशेषनिर्देशेन श्नाविकरणनिवृत्त्यर्थं सूत्रं स्यादत आह—न त्वश्नातिरेवेति । तथा हि सति 'नाश्नः' इत्येव वदेदिति भावः ॥ नियमज्ञापकस्य=नियमबोधकस्य ॥

(वार्तिकोक्तद्वितीयदूषणभाष्यम्)

लादेशे च ऋकारग्रहणं कर्तव्यम् । "कृपो रो लः", ऋकारस्य चेति वक्तव्यम् । इहापि यथा स्यात्—क्लृप्तः–क्लृप्तवानिति । यस्य पुनर्गृह्यन्ते, 'रः' इत्येव तस्य सिद्धम् ॥

(द्वितीयदूषणोद्धारभाष्यम्)

यस्यापि न गृह्यन्ते तस्याप्येष न दोषः । ऋकारोऽप्यत्र निर्दिश्यते ॥

कथम् ?

अविभक्तिको निर्देशः—कृप–उः–रः लः="कृपो रो लः" इति ॥

अथवा उभयतः स्फोटमात्रं निर्दिश्यते–रश्रुतेर्लश्रुतिर्भवतीति ॥

(प्रदीपः) अविभक्तिक इति । तत्र ऋकारनिर्देशस्य सामर्थ्याद्विभागं परिकल्प्यादेशो विधीयते ॥

स्फोटमात्रमिति । जातिस्फोट इत्यर्थः ॥ ततश्चान्तर्भूतानन्तर्भूतरेफलकारव्यक्तिव्यक्त्यं सामान्यं स्थान्यादेशभावेनाश्रीयते ॥

(उद्योतः) नन्वखण्डवर्णपक्ष ऋकारग्रहणेऽपि कथं सिध्यतीत्यत आह—तत्र ऋकारेति । एवं च रेफपदेन तत्सदृश आरोपितरेफत्ववानपि गृह्यत इति फलितम् ॥ मात्रशब्दः सामान्याभिप्राय इत्याह—जातीति ॥ जातिश्चावयवानवयवसाधारणीत्याशयेनाह—ततश्चेति । एवंविधा च रत्वलत्वजातिरेवेत्यतिप्रसक्तो न । स्थान्यादेशभावश्च जातेर्व्यक्तिद्वारको बोध्यः । वस्तुतः स्फोट एव श्रोत्रग्राह्यः । वायुनिष्ठरत्वादिना च तस्याभिव्यक्तिः । एवं च साक्षाद्रत्ववतोऽभावेन 'कल्पते'इत्यत्राप्यप्रवृत्तावस्य वैयर्थ्यापत्तिः ॥ एवं च रेफावभासिनः स्फोटस्य प्रसङ्गे लकारावभासः स्फोट इत्यर्थः ॥

एवं च ऋपावपि तत्प्रवृत्तिः संभवत्येव, तत्रापि रेफावभासत्त्वात् । आकारादौ तु नैवं ह्रस्वावभास इति न तत्राकारावभासप्रयुक्तकार्यापत्तिः । तदुक्तम्—रश्रुतेरित्यादि । यत्तु स्वतन्त्रास्वतन्त्रसाधारणजातिपरतयैतद्भाष्यव्याख्यानम् । तन्न । तादृशजातौ मानाभावात् । नरसिंहदृष्टान्तानुपपत्तेश्च । सादृश्यात्तु प्रत्यभिज्ञेत्यादिस्वोक्तिविरोधापत्तेश्च । किंचैवं सति 'रजातेः' इत्येव भगवान्वदेत् ॥ किञ्च तादृशजातिसत्त्वे वर्णैकदेशानामपि तज्जातिमत्त्वेन वर्णग्रहणेन ग्रहणपक्षस्यैव सिद्धा ग्रहणपक्षमुक्त्वा 'अथ वा न गृह्यन्ते' इति पक्षे तत्समाधानपरभाष्यासङ्गतेः । अत एवाष्टमे 'रषाभ्याम्–'इति सूत्रे–यथा नरसिंहावयवानां नरस्वसिंहत्वजातियोगाभावात्पुरुषभृगराजाभ्यामेकाकृतियोगाभावः, एवं वर्णवर्णैकदेशयोरपि–इति कैयट आह–इति वदन्ति ॥

(वार्तिकोक्ततृतीयदूषणभाष्यम्)

विनामे ऋकारग्रहणं कर्तव्यम् । "रषाभ्यां नो णः समानपदे", ऋकाराच्चेति वक्तव्यम् । इहापि यथा स्यात्—मातृणां-पितृणामिति ॥ यस्य पुनर्गृह्यन्ते 'रषाभ्याम्' इत्येव तस्य सिद्धम् ॥

(अग्रहणवादिभाष्यम्)

न सिध्यति । यत्तद्रेफात्परं भक्तेः, तेन व्यवहितत्वान्न प्राप्नोति ॥

(प्रदीपः) यत्तदिति । रेफात्-भक्तेः-इति समानाधिकरणे पञ्चम्यौ ॥

(ग्रहणवादिभाष्यम्)

मा भूदेवम् । अड्व्यवाय इत्येव सिद्धम् ॥

(प्रदीपः) अड्व्यवाय इति । ऋकारेण यथा दीर्घो गृह्यते, एवमृकारभागोऽपीति भावः ॥

(उद्द्योतः) ऋकारेणेति । ऋकारावयवस्य रेफस्येव तदज्भागस्यापि केनचिदकारादिना ग्रहणादट्त्वमिति मन्यते ॥

(अग्रहणवादिभाष्यम्)

न सिध्यति । वर्णैकदेशाः के वर्णग्रहणेन गृह्यन्ते ये व्यपवृक्ता अपि वर्णा भवन्ति ।

यच्चापि रेफात्परं भक्तेः, न तत्क्वचिदपि व्यपवृक्तं दृश्यते ॥

(प्रदीपः) न सिध्यतीति । तस्य भागस्य स्फुटप्रतिभासाविषयत्वाज्जात्यभिव्यक्तिहेतुत्वाभावाच्चेति भावः ॥

(उद्द्योतः) जात्यभिव्यक्तीति । अत्वादिजातीत्यर्थः ॥ एवं च न केनाप्यचा तद्ग्रहणमिति भावः । अत्र जात्यभिव्यक्तिहेतुत्वाभावे स्फुटप्रतिभासाविषयत्वं हेतुः । चः—हेतौ । अतो न सिध्यतीत्यर्थः ॥

(ग्रहणवादिभाष्यम्)

एवं तर्हि योगविभागः करिष्यते—"रषाभ्यां नो णः समानपदे", ततः—"व्यवाये" व्यवाये च रषाभ्यां नो णो भवतीति । ततः—"अट्कुप्वाङ्नुम्भिः" इति ।

इदमिदानीं किमर्थम् ?

नियमार्थम्—'एतैरेवाक्षरसमाम्नायिकैर्व्यवाये, नान्यैः' इति ॥

(प्रदीपः) एतैरेवेति । आकारादयोऽप्यकारादिभिः प्रत्यायितत्वादाक्षरसमाम्नायिकाः । भक्तिस्तु न प्रत्याय्या न प्रत्यायिका–इति नियमेन न निवर्त्यते ॥

(उद्द्योतः) नन्वाकारादिभिर्व्यवायेऽपि न स्यात्, आक्षरसमाम्नायिकत्वाभावादत आह—आकारादयोऽपीति ॥ भक्तिस्त्विति । असवर्णत्वादनुपदेशाच्चेति भावः

(अग्रहणवादिभाष्यम्)

यच्चापि न गृह्यन्ते तन्नाप्येष न दोषः । आचार्यप्रवृत्तिर्ज्ञापयति—भवत्यृकारान्नो णत्वमिति । यदयं क्षुभ्नादिषु नृनमनशब्दं पठति ॥

(उद्द्योतः) भाष्ये—नृनमनशब्दमिति । संज्ञाभूतमित्यभिप्रायः । गन्धर्वगानमित्यादौ व्युत्पत्तेः पूर्वं समासेऽपि णत्ववारणाय 'अखण्डपदे' इत्यर्थक'समानपदे' इत्यत्र पदस्यार्थबोधकस्यैव ग्रहणेन सखण्डत्वेऽसंशयां णत्वप्राप्त्यभावादिति बोध्यम् । 'छन्दस्यृत्' इत्यस्य तु नात्र प्राप्तिः । ईदृशे विषयेऽवग्रहाभावादित्याहुः ॥

(ग्रहणवादिभाष्यम्)

नैतदस्ति ज्ञापकम् । वृद्ध्यर्थमेतत्स्यात्—नार्नमनिः ॥

(अग्रहणवादिभाष्यम्)

यत्तर्हि तृप्नोतिशब्दं पठति ॥

(एकदेशिभाष्यम्)

यच्चापि नृनमनशब्दं पठति ॥

(बाधकस्मारणभाष्यम्)

ननु चोक्तम्—वृद्ध्यर्थमेतत्स्यात् ॥

(समाधानभाष्यम्)

बहिरङ्गा वृद्धिः, अन्तरङ्गं णत्वम् । असिद्धं बहिरङ्गमन्तरङ्गे ॥

अथवा–उपरिष्टाद्योगविभागः करिष्यते–"ऋतः" नो णो भवति । ततः—"छन्दस्यवग्रहात्" (८।४।२६) ऋत इत्येव ॥

(उद्द्योतः) बहिरङ्गा वृद्धिरिति । त्रिपाद्यामपि बहिरङ्गपरिभाषा प्रवर्तत इति वार्तिकमतेनैतत् । भाष्यमते तु तृप्नोतिशब्दपाठस्यैव ज्ञापकता बोध्या ॥ ऋतो नो ण इति । मातृणामित्यादौ दीर्घस्य बहिरङ्गासिद्धत्वाण्णत्वम् । यद्वा 'प्रशास्तॄणां' इति निर्देशादत्र तपरत्वं मुखसुखार्थमेव । उत्तरत्राऽप्येवमेव, फलाभावात् । ध्वनितं चेदं वृत्तौ ॥

(आक्षेपभाष्यम्)

***प्लुतावैच इदुतौ* (८।२।१०६)**

एतच्च वक्तव्यम् । यस्य पुनर्गृह्यन्ते गुरोरृतः-इत्येव प्लुत्या तस्य सिद्धम् ॥

(प्रदीपः) गुरोरृतेरिति । ऐकारो गुरुः, तस्य टेरिति सिद्धम् । तत्रन्यायाश्रयणाय गुरोरपि स्थाने प्लुतो भवति—

दे३वदत्तेति ॥

(उद्द्योतः) ननु गुर्वंवयवटेरित्यर्थाङ्गीकारे गुरुरूपटेः प्लुतो न स्यादत आह—तत्रेति । स्थानषष्ठ्यन्तावयवषष्ठ्यन्तयोर्गुरुशब्दयोरित्यर्थः । गुर्वंवयवटिश्चैच एव संभवति, नान्यस्य—आकारादेः, तदवयवस्य व्यपवृक्तत्वाभावादिति भावः ॥

(आक्षेपबाधकभाष्यम्)

यस्यापि न गृह्यन्ते तस्याप्येष न दोषः । क्रियत एतन्न्यास एव ॥

(प्रदीपः) क्रियते न्यास एवेति । अवश्यकर्तव्यतां दर्शयति । व्यपवृक्तेऽपि भागयोर्विवृततरत्वात् प्रयत्नभेदादिकारोकाराभ्यामग्रहणादच्त्वाभावात् ॥

(उद्द्योतः) अच्त्वाभावादिति । तन्मूलटित्वाभावाच्चेत्यपि बोध्यम् ॥

(४७ आक्षेपवार्तिकम् ॥ ६ ॥)

॥ * ॥ तुल्यरूपे संयोगे द्विव्यञ्जनविधिः ॥ * ॥

(भाष्यम्)

तुल्यरूपे संयोगे द्विव्यञ्जनाश्रयो विधिर्न सिध्यति—कु३क्कुटः, पि३प्पलः, पि३त्तमिति ॥ यस्य पुनर्गृह्यन्ते तस्य द्वौ ककारौ, द्वौ पकारौ, द्वौ तकारौ ॥

(प्रदीपः) तुल्यरूप इति । तुल्यरूपावयवत्वात्संयोगस्तुल्यरूपः । तस्यैकवर्णत्वं पूर्वपक्षे, सिद्धान्ते तु वर्णद्वयरूपता । आशूच्चारणात्तु भ्रान्तमेकत्वज्ञानमिति शिष्टसमाचारः ॥

(उद्द्योतः) संयोग इति । संयोगसंज्ञार्ह इत्यर्थः ॥ तस्यैकवर्णत्वमिति । एवं च संयोगसंज्ञा न स्यादिति भावः ॥ 'संयोगे' इति भाष्यं तु संयोगार्ह इत्यर्थपरमिति तात्पर्यम् ॥ शिष्टसमाचारः=शिष्टव्यवहारः ॥

(आक्षेपबाधकभाष्यम्)

यस्यापि न गृह्यन्ते तस्यापि द्वौ ककारौ, द्वौ पकारौ, द्वौ तकारौ ॥

कथम् ?

मात्राकालोऽत्र गम्यते । न च मात्रिकं व्यञ्जनमस्ति । अनुपदिष्टं सत्कथं शक्यं विज्ञातुम् । असच्च कथं शक्यं प्रतिपत्तुम् ॥

(उद्द्योतः) भाष्ये—मात्राकालोऽत्रेति । बहुव्रीहिः, संयोगोऽन्यपदार्थः ॥ मात्रिकव्यञ्जनाभावेऽनुपदिष्टत्वं हेतुः । कुक्कुट इत्याद्युच्चारणं तु न उपदेशः ॥ अनुपदिष्टत्वं नाम अक्षरसमाम्नायेऽपठितत्वं ग्राहकशास्त्रेणागृहीतत्वं च ॥ अनुपदिष्टं सत्=सत्त्वेन कथं शक्यं विज्ञातुमित्यर्थः । एवं चानुपदिष्टस्यासत्त्वात् तत्प्रतिपत्तिरशक्येत्याह—असच्चेति । क्वचित्तु 'असच्च—' इत्यादिग्रन्थो न दृश्यते ॥ अनेन लृकारापाठे तस्यासत्त्वशङ्कया तयोः सावर्ण्यविधिरप्यशक्य इति सूचितम् ॥

(आक्षेपसाधकभाष्यम्)

यद्यपि तावदत्रैतच्छक्यते वक्तुं—यत्रैतन्नास्ति 'अण् सवर्णान् गृह्णाति' इति ॥ इह तु कथम्—सय्ँयन्ता सव्ँवत्सरः, यल्ँलोकम्, तल्ँलोकमिति यत्रैतदस्ति 'अण् सवर्णान् गृह्णाति' इति ?

(उद्द्योतः) यत्रैतदस्तीति—भाष्ये । 'हलोऽनन्तराः—' इत्यत्र यकारादिभिरस्य ग्रहणे हल्द्वयाभाव इति भावः ॥

(आक्षेपबाधकभाष्यम्)

अत्रापि मात्राकालो गृह्यते । न च मात्रिकं व्यञ्जनमस्ति । अनुपदिष्टं सत्कथं शक्यं विज्ञातुम् ॥ ४ ॥

(प्रदीपः) अत्रापीति । सानुनासिकनिरनुनासिकौ द्वावत्र वर्णावित्यर्थः ॥

(उद्द्योतः) सानुनासिकेति । अणुदित्सूत्रं हि विद्यमानस्य लोकसिद्धस्य सवर्णस्य ग्राहकमेव, न त्वप्रसिद्धसवर्णकल्पकमिति भावः ॥

(शिवसूत्रम्)

॥ हयवरट् ॥ ५ ॥

(अथ हकाराधिकरणम्)

(वार्तिकावतरणभाष्यम्)

सर्वे वर्णाः सकृदुपदिष्टाः, अयं हकारो द्विरुपदिश्यते—पूर्वश्चैव परश्च । यदि पुनः पूर्व एवोपदिश्येत, पर एव वा । कश्चात्र विशेषः ?

(प्रदीपः) हयवरट् ॥ पूर्वश्चेति । पूर्वपरोच्चारणक्रियाभेदादेकस्यैव हकारस्य पूर्वपरव्यपदेशः ॥

(उद्द्योतः) हयवरट् ॥ ननु 'अयं हकारः' इत्यनेनैकत्वं हकारस्य सूचितमिति कथं तद्विरुद्धं 'पूर्वश्च'इत्यादिना भेदाश्रयणमत आह—पूर्वपरेति । एतद्भाष्यात् 'एकत्वं वर्णानाम्' इत्येव पक्षो भगवतः संमत इति ज्ञायते ॥ भाष्ये—यदि पुनरिति । न चैवं परहकाराभावे लकारस्याप्यभावेन तन्त्राद्याश्रयणेन 'हलन्त्यम्' इत्यत्रान्योन्याश्रयपरिहारो वक्ष्यमाणो विरुध्येतेति वाच्यम् । 'रन्त्यं हर्'इति न्यासेन 'लन्त्यं यल्'इति न्यासेन वा तत्परिहाराल्लाघवाभावेऽपि—एवं कर्तुं शक्यं न वा—इत्येव विचारतात्पर्यात् । यद्वा 'हरन्त्यम्' इत्यस्यैवावृत्त्या हर्बोधकसूत्रसमुदायान्त्यमित्यर्थः ॥

परे तु परहकाराभावेऽपि "ल्" इत्येव सूत्रं कार्यं प्रातिशाख्यादिप्रसिद्धहलादिप्रत्याहारसिद्ध्यर्थम् । तदर्थं तन्त्रस्यापि शक्तिकल्पने गौरवात् । 'हलन्त्यम्' इत्यस्यावृत्त्या 'हल्प्रत्याहारबोधकसूत्रसमुदायान्त्यमित्' इत्यप्यर्थं इत्यदोष इत्याहुः ॥

(४८ पूर्वत्रानुपदेशे दूषणवार्तिकम् ॥ १ ॥)

॥ * ॥ हकारस्य परोपदेशेऽड्ग्रहणेषु हग्रहणम् ॥ * ॥

(भाष्यम्)

हकारस्य परोपदेशेऽड्ग्रहणेषु हग्रहणं कर्तव्यम् । "आतोऽटि नित्यम्" "शश्छोऽटि" "दीर्घादटि समानपादे", हकारे चेति वक्तव्यम् । इहापि यथा स्यात्—महाँ हि सः ॥

(प्रदीपः) शश्छोऽटीति । हकारपरस्य शकारस्याभावात् प्रसङ्गोच्चारितमेतत् ॥

(उद्द्योतः) अड्ग्रहणेष्विति । अट् गृह्यते येषु सूत्रेष्वित्यर्थः ॥ 'शश्छोऽटि'इत्यस्योदाहरणादाने बीजमाह—हकारपरस्येति । न च 'तत् श् ह्-इत्याद्' इत्युदाहरणसंभवः । शास्त्रबोधितं सौत्रं च विहाय हलामुच्चारणार्थाचं विनोच्चारणस्यासाधुत्वेन तादृशोदाहरणाभाव इत्याशयात् । अत्र च भाष्ये एतदुदाहरणादानमेव मानम् । 'आतोऽटि' 'दीर्घादटि-' इत्युभयोरुदाहरणं—'महाँ हि सः' इति । 'अट्कुपु-' इति सूत्रेऽपि ग्रहणफलं 'अर्हेण' इति बोध्यम् ॥

(४९ पूर्वत्रानुपदेशे दूषणवार्तिकम् ॥ २ ॥)

॥ * ॥ उत्त्वे च ॥ * ॥

(भाष्यम्)

उत्त्वे च हकारग्रहणं कर्तव्यम् ; "अतो रोरप्लुतादप्लुते" "हशि च" हकारे चेति वक्तव्यम् । इहापि यथा स्यात्—पुरुषो हसति, ब्राह्मणो हसतीति ॥

(प्रदीपः) अत्त्वमपि न प्राप्नोतीति वक्तव्यं 'भो हसति' इति रोर्यत्वार्थम् ॥

(उद्द्योतः) अत्त्वमपीति । एवंमिणुत्वस्याप्युपलक्षणम् । तेन लिलिहिढ्वे-इत्यादौ 'विभाषेटः' इति ढत्वविकल्पसिद्धिरिति केचित् ॥ भाष्ये 'हशि च' इति सिद्धान्तर्गत्या निर्देशः । इदानीं तु 'अशि च'इति सूत्रम् ॥

(पूर्वोपदेशाङ्गीकारभाष्यम्)

अस्तु तर्हि पूर्वोपदेशः ।

(परत्रानुपदेशे दूषणभाष्यवार्तिकम्)

पूर्वोपदेशे किर्त्वक्त्वेड्विधयो झल्ग्रहणानि च

(भाष्यम्)

यदि पूर्वोपदेशः कित्त्वं विधेयम्—स्निहित्वा-स्नेहित्वा, सिस्निहिषति-सिस्नेहिषति, "रलोऽव्युपधाद्धलादेः-" इति कित्त्वं न प्राप्नोति ॥

क्सविधिः । क्सश्च विधेयः—अधुक्षत्, अलिक्षत्, "शल इगुपधादनिटः क्सः" इति क्सो न प्राप्नोति ॥

इड्विधिः । इट् च विधेयः—रुदिहि, स्वपिहि, वलादिलक्षण इण्न प्राप्नोति ॥

'झल्ग्रहणानि च' ।

किम्?

अहकाराणि स्युः ॥

तत्र को दोषः?

"झलो झलि" इतीह न स्यात्-अदाग्धाम्, अदाग्धम् ।

तस्मात्पूर्वश्चैवोपदेष्टव्यः परश्च ॥

(उद्द्योतः) अहकाराणि स्युरिति । अतस्तत्र हकारग्रहणं कर्तव्यमिति भावः ॥ अदाग्धामिति । दत्वस्यासिद्धत्वादिति भावः ॥

(उपसंहारभाष्यम्)

यदि किंचिदन्यत्राप्युपदेशे प्रयोजनमस्ति, तत्राप्युपदेशः कर्तव्यः ॥

(प्रदीपः) यदि किंचिदिति । प्रयोजनार्थो हि वर्णानामुपदेशो न स्वरूपप्रतिपत्त्यर्थः ॥

(उद्द्योतः) स्वरूपप्रतिपत्त्यर्थं एवायमक्षरसमाम्नाय इति भ्रमं वारयति—भाष्ये-यदि किंचिदिति ॥ तथाचष्टे—प्रयोजनार्थ इति । शास्त्रीयप्रयोजनार्थ इत्यर्थः । एवं चाधहकारस्याणिणोरपि प्रयोजनं सूचितम् । अत एव मल्ला हसन्तीति 'पुंयोगात्' इति सूत्रे भाष्यप्रयोगः सङ्गच्छते । एतेन पूर्वहकारोपदेशप्रयोजनवार्तिके न्यूनता परिहृता ॥ 'कर्तव्यः' इत्यस्य स्यात् इति शेषः । उपदेशः—अत्रोच्चारणमात्रम् ॥ अन्यत्रापि=प्रत्याहारान्तरे । सर्वथा हकारस्य द्वेधोपदेशः कर्तव्य इत्यत्रास्य तात्पर्यम् ॥

(इति हकाराधिकरणम्)

(अथ रेफाधिकरणम्)

(वार्तिकावतरणभाष्यम्)

इदं विचार्यते—अयं रेफो यकारवकाराभ्यां पूर्व एवोपदिश्येत-'हरयवट्' इति, पर एव वा यथान्यासमिति । कश्चात्र विशेषः?

(प्रदीपः) इदमिति । उभयत्रापि दोषप्रयोजनसद्भावात्प्रश्नः ॥

(उद्द्योतः) दोषप्रयोजनेति । अन्यतरपक्षीयदोष एवान्यतरपक्षे प्रयोजनमिति बोध्यम् ॥

(५० यथान्यासोपदेशे दूषणवार्तिकम् ॥ १ ॥)

॥ * ॥ रेफस्य परोपदेशेऽनुनासिकद्विर्वचनपरसवर्णप्रतिषेधः ॥ * ॥

(भाष्यम्)

रेफस्य परोपदेशेऽनुनासिकद्विर्वचनपरसवर्णानां प्रतिषेधो वक्तव्यः ॥

अनुनासिकस्य—स्वर्नयति, प्रातर्नयति-इति । "यरोऽनुनासिकेऽनुनासिको वा" इत्यनुनासिकं प्राप्नोति ॥

द्विर्वचनस्य—मद्रहृदः, भद्रहृदः, यरः-इति द्विर्वचनं प्राप्नोति ।

परसवर्णस्य—कुण्डं रथेन, वनं रथेन, "अनुस्वारस्य ययि-" इति परसवर्णः प्राप्नोति ॥

(प्रदीपः) स्वर्णयतीति । णकारोऽत्र प्राप्नोति । न ह्यत्र सवर्णग्रहणमस्ति ॥ मद्र्ह्लद इति । द्विर्वचने कृते तस्यासिद्धत्वात् 'रो रि' इति रेफलोपो नास्ति, 'हलो यमां' इति लोपस्तु पाक्षिक इति पक्षे रेफद्वयश्रवणप्रसङ्गः ॥ कुण्डं रथेनेति । अनुनासिकेनैव परसवर्णेन भाव्यमिति नियमाभावाद्रेफः प्राप्नोति, तस्य चासिद्धत्वात् 'रो रि' इति रेफलोपो नास्ति ॥

(उद्योतः) णकारोऽत्रेति । स्थानेऽन्तरतमत्वादिति भावः ॥ ननु रेफस्य सवर्णाभावात्कथमत्रानुनासिकोऽत आह—न ह्यत्रेति ॥ ननु द्वित्वेऽपि 'रो रि' इति 'हलो यमां' इति लोपाच्च दोषोऽत आह—द्विर्वचन इति ॥

(यकारात्पूर्वपाठाभ्युपगमभाष्यम्)

अस्तु तर्हि पूर्वोपदेशः ।

(पूर्वोपदेशदूषणभाष्यवार्तिकम्)

पूर्वोपदेशे कित्त्वप्रतिषेधो व्यलोपवचनं च

(भाष्यम्)

यदि पूर्वोपदेशः कित्त्वं प्रतिषेध्यम् । देवित्वा, दिदेविषति । "रलो व्युपधात्-" इति किव्वं प्राप्नोति ॥

(दूषणनिराकरणभाष्यम्)

नैष दोषः । नैवं विज्ञायते—'रलो व्युपधात्' इति ॥

किं तर्हि ?

"रलः-अव्-व्युपधात्" इति ॥

किमिदम्—अव् व्युपधात्—इति ?

अवकारान्तात् व्युपधात्—अव्व्युपधादिति ॥

(उद्योतः) भाष्ये—अव्व्युपधादिति । 'अवः' इति लुप्तपञ्चमीकम् ॥ ननु पूर्वोपदेशे 'इमणः-' इत्यादौ यथासङ्ख्यनिर्वाहः कथमिति चेन्न । संज्ञाविधानसामर्थ्येन तत्र तद्भावितपक्षाश्रयणान्न दोषः ॥

(व्याख्याभाष्यम्)

'व्यलोपवचनं च' । व्योश्च लोपो वक्तव्यः । गौधेरः, पचेरन्, यजेरन् । 'जीवे रदानुक्'—जीरदानुः । वलीति लोपो न प्राप्नोति ॥

(दूषणनिराकरणभाष्यम्)

नैष दोषः । रेफोऽप्यत्र निर्दिश्यते—"लोपो व्योर्वलि" इति, रेफे च वलि चेति ॥

(यथान्यासाऽभ्युपगमभाष्यम्)

अथवा पुनरस्तु परोपदेशः ॥

(दोषस्मारणभाष्यम्)

ननु चोक्तम्—*रेफस्य परोपदेशेऽनुनासिकद्विर्वचनपरसवर्णप्रतिषेधः* इति ॥

(समाधानभाष्यम्)

अनुनासिकपरसवर्णयोस्तावत्प्रतिषेधो न वक्तव्यः । रेफोष्मणां सवर्णा न सन्ति ॥

(प्रदीपः) रेफोष्मणामिति । अनुनासिकपरसवर्णविधाने हि स्थानेऽन्तरतम इति परिभाषोपस्थानाद्दोषाभावः । न हि रेफस्य णकारोऽन्तरतमः, नाप्यनुस्वारस्य रेफः ॥

(उद्योतः) भाष्ये—रेफोष्मणामिति । विजातीया इति शेषः । तेन सजातीयेषु सत्स्वपि न दोषः ॥ ननु माभूद्रेफस्य विजातीयः सवर्णः, तथाप्यनुनासिकविधौ सवर्णग्रहणाभावादनुनासिकः स्यादेवेत्यत आह—अनुनासिकपरेति ॥ न हि रेफस्येति । न च रेफस्य णकारः स्थानेनान्तरतमो भवत्येवेति वाच्यम् । 'स्थानेऽन्तरतमे' इति सप्तम्यन्तपाठे स्थानप्रयत्नोभयान्तरतमे स्पर्शे 'चिन्मात्रम्' इत्यादौ चरितार्थोऽनुनासिकविधिः प्रयत्नासदृशे रेफे न प्रवर्तते—इति भावात् ॥ नापीति । यद्यप्यन्तरतमानन्तरतमयोः प्राप्तावन्तरतम एवेति 'स्थानेऽन्तरतमः' इत्यनेन नियमः, 'कुण्डं-रथेन' इत्यादौ चानन्तरतमस्यैव प्राप्तिरितीदमयुक्तम्; तथापि संभवदनुस्वारान्तरतमके 'अङ्कितः' इत्यादौ चरितार्थः परसवर्णविधी रेफे न प्रवर्तते—इति भावः । इदं जातिपक्षे इति केचित् ॥ वस्तुतो व्यक्तिपक्षेऽपि तादृशव्यक्तौ चरितार्थोऽस्यां व्यक्तौ न प्रवर्तते—इति वक्तुं शक्यम् । तद्ध्वनयति 'इको यणचि' इत्यत्र कैयटः—"द्रव्येऽपि पदार्थे उत्सर्गापवादभावः संदिग्धत्वाश्रयोऽस्त्येव" इति ॥ केचित्तु 'स्थानेऽन्तरतमे' इति सप्तम्यन्तपाठप्रत्याख्यानपरभाष्यविरोधेनास्या युक्तेरसंभवदुक्तिकत्वम् । किं चैवं सति ऊष्मग्रहणं भाष्ये व्यर्थं स्यात् । तस्मादनुनासिकविधौ सवर्णपदापकर्षपरं भाष्यम् । रेफोष्मणामित्यस्य चानुनासिकोऽनुस्वारान्तरतमश्च सवर्णो नास्तीत्यर्थः । अत एव मद्दिष्मानित्यादौ सन्नरीत्या स्थानप्रयत्नोभयान्तरतमऋकारसम्भवेऽपि नानुनासिकः, 'नाज्झलौ' इति निषेधेन सवर्णत्वाभावादिति भाष्याशय इत्याहुः ॥

(द्विर्वचनांशसमाधानभाष्यम्)

द्विर्वचनेऽपि—नेमौ रहौ कार्यिणौ द्विर्वचनस्य ॥

किं तर्हि ?

निमित्तमिमौ रहौ द्विर्वचनस्य । तद्यथा—'ब्राह्मणा भोज्यन्तां माठरकौण्डिन्यौ परिवेविषाताम्' इति । नेदानीं तौ भुञ्जाते ॥

(प्रदीपः) नेमौ रहाविति । हकारवद्रेफोऽपि न कार्यीत्यर्थः । तत्रैकवाक्यतायां सामान्यविशेषविध्योर्लोकव्यवहारादेव शब्दार्थसंबन्धपरिज्ञानवत्सामान्यविधेर्विशेषविधिर्बाधकः । प्रत्यक्षश्च विशेषविधिः, सामान्यविधिस्त्वनुमेयः—इति रेफस्य कार्यित्वं निमित्तत्वेन बाध्यते । दध्युदकादौ तु स्थानित्वेन निमित्तत्वमिकां तस्मादित्युत्तरस्यादेर्लोपकाल बाध्यते । लक्ष्यस्थित्यपेक्षणाद्वा बाध्यबाधकभावस्य । क्वचिदपेक्षा नास्ति, यथा—चिचीषतीति दीर्घत्वद्विर्वचनयोः ॥

(उद्योतः) नन्वयत्वादप्रसक्तद्वित्वस्य हस्य ग्रहणमयुक्तमत आह—हकारवदिति ॥ ननु एककर्तृकयोर्भोजनपरिवेषणयोर्युगपदसम्भवात्स्तु तत्र बाधः, प्रकृते तु लक्ष्यभेदेन भिन्नवाक्यावगतनिमित्तकार्यिभावः किं न स्यात्; यथा—अवगतकार्यित्वस्यापि इको निमित्तत्वं दध्युदकादावत आह—तत्रेति । लक्ष्यभेदेन कार्यित्वनिमित्तत्वसंभवेऽपीत्यर्थः ॥ सामान्यविशेषविध्योरेकवाक्यतायामित्यन्वयः ।

शब्दः=वाक्यात्मा, अर्थः=तदर्थः, संबन्धः=प्रतिपाद्यप्रतिपादकभावः, तेषां परिज्ञानं। तद्यथा लोकव्यवहारादेव, तथा तयोर्बाध्यबाधकभावः—संभवेऽपि भवतीत्येतदपि लोकव्यवहारादेव 'ब्राह्मणेभ्यो दधि दीयतां तक्रं कौण्डिन्याय' इत्यादिरूपादवगतमित्यर्थः । विशेषसंनिधाने सामान्यशब्दस्य तद्व्यतिरिक्तपरत्वं च तद्बीजम् ॥ 'परिज्ञानवत्' इति पाठः ॥ एवञ्च 'अचो रहाभ्याम्—' इत्यत्र सामान्यविशेषविधित्वाभावेऽपि तत्र बाधे यद्बीजं तत्प्रकृतेऽप्यस्त्येवेत्याह—प्रत्यक्षश्चेति । अविलम्बितप्रतीतिकत्वं—प्रत्यक्षत्वम् । विलम्बिततत्कत्वं च—अनुमेयत्वम् ॥ लक्ष्येति । ज्ञापकाल्लक्ष्यानुरोधाद्वा सत्यपि सामान्यविशेषभावे क्वचिद्बाधकत्वं विशेषविधेर्नाश्रीयते जातिव्यक्तिपक्षयोरुभयोरपीति भावः ॥ क्वचिदपेक्षा नास्तीति । बाध्यबाधकभावस्येति शेषः ॥ यथेति । बाध्यबाधकभावाभावे दृष्टान्तोऽयम्, न तु कार्यित्वनिमित्तत्वयोः समावेशे इति बोध्यम् ॥ केचित्तु तक्रकौण्डिन्यन्यायोऽपि सामान्यविषयानाक्रान्तविषयाभावरूपानवकाशत्वमूलक एव । अस्ति च प्रकृते तत् । न ह्येतद्बोध्यनिमित्तत्वं सामान्यशत्वप्रयुक्तकार्यित्वानाक्रान्तं क्वचिदप्यस्ति, सर्वत्राचः परत्वात् 'अनचि' इत्यस्य प्राप्तेः । अतो युक्तो लक्ष्यानुरोधात्सामान्येन कार्यित्वबाधः । न चैवं 'इको यण्—' इत्यादौ, 'मत्वर्थः' इत्यादौ सामान्यप्राप्तनिमित्तत्वाभावेन कार्यित्वस्य चारितार्थ्यात्—इति भाष्याभिप्रायमाहुः ॥

(इति रेफाधिकरणम्)

(अथायोगवाहोपदेशाधिकरणम्)

(वार्तिकावतरणभाष्यम्)

इदं विचार्यते—इमेऽयोगवाहा न क्वचिदुपदिश्यन्ते, श्रूयन्ते च । तेषां कार्यार्थ उपदेशः कर्तव्यः ॥

के पुनरयोगवाहाः ?

विसर्जनीयजिह्वामूलीयोपध्मानीयानुस्वारयमाः ॥

कथं पुनरयोगवाहाः ?

यद्युक्ता वहन्ति, अनुपदिष्टाश्च श्रूयन्ते ॥

(प्रदीपः) **इम इति** । विधानादेषां साधुत्वं स्यात्, प्रत्याहारप्रतिबद्धं तु कार्यं न प्राप्नोति ॥ **के पुनरिति** । तत्स्वरूपप्रश्नः ॥ **कथमिति** । प्रवृत्तिनिमित्तप्रश्नः । 'अयुक्ताः' इत्यस्यैव हेतुकथनम्—**अनुपदिष्टाश्च**—इति । **अयुक्ताः**—प्रत्याहारलक्षणेन पाठाभावादसंबद्धा इत्यर्थः । उपदेशो द्विविधः—पाठः, ग्रहणकशास्त्रेण प्रत्यायनं च । स द्विविधोऽप्येषां नास्तीत्यर्थः । चशब्दो हेतौ । यतोऽनुपदिष्टास्ततोऽयुक्ता इत्यर्थः । केचित्तु चशब्दो न पठ्यते ॥

(उद्योतः) ननु 'कार्यार्थः' इत्यत्र कार्य-साधुत्वं चेत् 'खरवसानयोः' इत्यादिना सिद्धमत आह—**विधानादिति** । 'उपदिश्यन्ते' इति पाठे भाष्ये वर्तमानसामीप्ये लट् । उपदिष्टा इत्यर्थः ॥ **प्रवृत्तिनिमित्तेति** । प्रकृते भासमानवैशिष्ट्यप्रतियोगिरूपः प्रकारः—धमर्थ इति भावः । केन प्रवृत्तिनिमित्तेनायोगवाहशब्दवाच्यत्वमेषामित्यत्र तात्पर्यम् ॥ ननु 'अनुपदिष्टाश्च' इति चकारश्रवणादनुच्चारितत्वमयोगवाहशब्दस्य प्रवृत्तिनिमित्तान्तरमित्याभाति । तदयुक्तम्, अनुपदेशपदार्थस्यानुच्चारणस्य तत्राभावात् । प्रयोगेषूच्चारितत्वात् । न च प्रत्याहारसूत्रानुच्चारितत्वं तथा, 'यद्युक्ताः' इत्यनेनैव तदर्थलाभेन पौनरुक्त्यापत्तेरत आह—**अयुक्ता इत्यस्यैव हेतुकथनमिति** । प्रत्याहारबोधकलक्षणेनायुक्ता इत्यन्वयः । तच्चाचष्टे—**पाठाभावादिति** । ग्रहणकशास्त्रेण प्रदेशे प्रवर्तमानेन यो वर्णस्तेषां ग्राहकः, तस्य पाठाभावादित्यप्यर्थः ॥ **एषां नास्तीति** । अतोऽयुक्ता इत्यर्थः । एवं चाक्षरसमाम्नायेऽयुक्ताः सन्तो वहन्ति=प्रयोगं निर्वाहयन्तीत्ययोगवाहपदव्युत्पत्तिर्दर्शिता ॥ **न पठ्यत इति** । तत्र 'यतः' इत्यध्याहार्यमिति भावः ॥

(वार्तिकावतरणभाष्यम्)

क्व पुनरेषामुपदेशः कर्तव्यः ?

(५१ सिद्धान्तवार्तिकम् ॥ १ ॥)

॥ * ॥ अयोगवाहानामट्सु णत्वम् ॥ * ॥

(भाष्यम्)

अयोगवाहानामट्सूपदेशः कर्तव्यः ॥

किं प्रयोजनम् ?

णत्वम् । उरःकेण—उरःकेण, उरःपेण—उरःपेण । "अड्व्यवाये" इति णत्वं सिद्धं भवति ॥

(उद्योतः) भाष्ये—**उरःकेणेति** । उरः कायतीति सुबुत्पत्तेः पूर्वं समासेऽपि 'सोपदादौ' इति न सत्वम्, 'पाशकल्पककाम्येषु' एव तत्प्रवृत्तेः ॥

(५२ सिद्धान्तवार्तिकम् ॥ २ ॥)

॥ * ॥ शर्षु जश्भावषत्वे ॥ * ॥

(भाष्यम्)

शर्षूपदेशः कर्तव्यः ॥

किं प्रयोजनम् ?

जश्भावषत्वे । अयमुब्जिरुपध्मानीयोपधः पठ्यते । तस्य जश्त्वे कृते 'उब्जिता—उब्जितुम्' इत्येतद्रूपं यथा स्यात् ॥

(प्रदीपः) **शर्ष्विति** । शर्षु पाठे झल्त्वमिति 'झलां जश् झशि' इति जश्त्वं सिध्यति ॥

(उद्योतः) ननु 'शरां जशो भवन्ति' इति लक्षणाभावात् शर्षुपाठस्य न जश्भावः प्रयोजनमत आह—**शर्षु पाठे इति** ॥

(उपध्मानीयोपधदूषणभाष्यम्)

यद्युपध्मानीयोपधः पठ्यते, उब्जिजिषतीत्युपध्मानीयादेरेव द्विर्वचनं प्राप्नोति । दकारोपधे पुनः "न न्द्राः संयोगादयः" (६।१।३) इति प्रतिषेधः सिद्धो भवति ॥

(प्रदीपः) **उपध्मानीयादेरिति** । यदि द्विर्वचने पूर्वत्र जश्त्वमसिद्धम्, अथापि **'पूर्वत्रासिद्धीयमद्विर्वचने'** इति सिद्धं । सर्वथोबिब्जिषतीति प्राप्नोति ॥

(उद्योतः) **यदीति** । 'पूर्वत्र द्विर्वचने—इत्यन्वयः ॥ ननु पूर्वं द्वित्वे जश्त्वात्पूर्वमेव हलादिः शेषे कथमुपध्मानीयस्याभ्यासे

जश्त्वं झश्परत्वाभावात् । 'अभ्यासे चर्च' इत्यनेन तु आन्तरतम्यात्प्रकृतिचरां चर एवेति उपध्मानीय एव स्यादिति चेत् न; चिन्त्यमेवैतत् । उपध्मानीयश्रवणापादनेनापि भाष्यसामञ्जस्यात् । अन्ये तु द्वित्वे कृतेऽपि द्वित्वाश्रयस्य कार्ये कर्तव्येऽसिद्धत्वं नेत्यपि

'पूर्वत्रासिद्धीयं' इत्यस्यार्थ इति परत्वाज्जश्त्वे कृत एव 'हलादिः शेषः' इत्याशयान्न दोषः ॥

(दकारोपधदूषणभाष्यम्)

यदि दकारोपधः पठ्यते, का रूपसिद्धिः—उब्जिता, उब्जितुमिति ?

(दकारोपधदूषणनिराकरणभाष्यम्)

असिद्धे भ उब्जेः ।

इदमस्ति—"स्तोः श्चुना श्चुः" (८।४।४०) इति, ततो वक्ष्यामि—"भ उब्जेः" उब्जेः श्चुना सन्निपाते भो भवतीति ॥

तत्तर्हि वक्तव्यम् ॥

न वक्तव्यम्, निपातनादेव सिद्धम् ।

किं निपातनम् ?

"भुजन्युब्जौ पाण्युपतापयोः" इति ॥

इहापि तर्हि प्राप्नोति-अभ्युद्गः, समुद्ग इति ॥

अकुत्वविषये तन्निपातनम् ॥ अथवा नैतदुब्जे रूपं, गमेरेतत् ड्युपसर्गाड्डो विधीयते । अभ्युद्गतः-अभ्युद्गः, समुद्गतः-समुद्ग इति ॥

(प्रदीपः) निपातनादिति । द्विर्वचनं कथम् ? निपातनाद्वाक्यशेषोऽनुमीयते—असिद्धप्रकरणे 'स्तोश्चुना श्चुः' इत्यत्र 'उब्जेर्भः' इति । तत्र 'न न्द्राः' इति दकारस्य द्विर्वचननिषेधः कर्तव्यो न तु द्विर्वचनमिति **'पूर्वत्रासिद्धीयमद्विर्वचने'** इत्यस्याप्रवृत्त्या भत्वस्यासिद्धत्वादिष्टद्विर्वचनप्रसिद्धिः ॥ अथापि न वाक्यशेषानुमानं, निपातनमेव प्रतिपादकं, तथापि दकारोपधनिर्देशसामर्थ्याद्द्विर्वचने कृते दकारस्य बत्वं प्रवर्तते ॥

अकुत्वविषय इति । विशिष्टविषयमनुमानमित्यर्थः ॥

(उद्द्योतः) **द्विर्वचन कथमिति ।** बकाररहितस्येति शेषः ॥ ननु निपातनाल्लक्षणमात्रं स्यान्न तु प्रदेशविशेषावच्छिन्नमत आह—**अथापीति ।** न च 'अभ्युद्गः' इत्यादौ दकारोच्चारणं सार्थकं, 'नैतदुब्जे रूपं' इति भाष्योक्तौ दोषाभावात् । उपतापातिरिक्तविषयेऽसात्वत्र नानभिधानादिति तदाशयः ॥ **'अकुत्वविषये निपातनं'** इति पक्षान्तरे त्वाद्यमेव समाधानम् ॥

(प्रयोजनवार्तिकांशव्याख्याभाष्यम्)

षत्वं च प्रयोजनम् । सर्पिःषु, धनुःषु । 'शर्व्यवाये' इति षत्वं सिद्धं भवति, "नुम्विसर्जनीयशर्व्यवायेऽपि" (८।३।५८) इति विसर्जनीयग्रहणं न कर्तव्यं भवति ॥

(आक्षेपभाष्यम्)

नुमश्चापि तर्हि ग्रहणं शक्यमकर्तुम् ।

कथं—सर्पींषि, धनूंषि ?

अनुस्वारे कृते 'शर्व्यवाये' इत्येव सिद्धम् ॥

(समाधानभाष्यम्)

अवश्यं नुमो ग्रहणं कर्तव्यम् । अनुस्वारविशेषणं नुम्ग्रहणम् । नुमो योऽनुस्वारस्तत्र यथा स्यात्, इह मा भूत्-पुंस्विति ॥

(प्रदीपः) **अवश्यमिति ।** अनुस्वारस्य शर्त्वात्तद्व्यवाये षत्वे सिद्धे नुम्ग्रहणं नियमार्थम्—नुमो योऽनुस्वारस्तत्रैव यथा स्यात्, अन्यत्र मा भूत्—पुंस्विति ॥

(उद्द्योतः) **अनुस्वारस्य शर्त्वादिति ।** यद्यपि इण्कवर्गाभ्यामुत्तरो नुमा व्यवहितः सकारः 'सुहिन्सु' इत्यादौ संभवति, तथापि तदनभिधानमिति भावः । 'पुंसु' इत्यत्र 'संपुङ्कानां-' इत्येतत्प्रवृत्तिपरविवरणग्रन्थस्तु चिन्त्य एव । तस्य 'समः सुटि' 'पुमः खय्यम्परे' 'कानाम्रेडिते' इति सूत्रत्रयमात्रविषयत्वात् ॥

(वार्तिकावतरणभाष्यम्)

अथवाऽविशेषेणोपदेशः कर्तव्यः ॥

(प्रदीपः) **अविशेषेणेति ।** प्रयोजनविशेषमनपेक्ष्य सकलप्रयोजनोद्देशेन यत्र यत्र प्रदेशे प्रयोजनसिद्धिस्तत्र तत्रोपदेशः कार्य इत्यर्थः ॥

(उद्द्योतः) ननु सूत्रविशेषानाश्रयणे तत्प्रत्याहारासंनिवेशात्कथं तन्निबन्धनकार्यप्रवृत्तिरत आह—**प्रयोजनविशेषमिति ॥** **'अविशेषेण'** इति भाष्यस्य प्रयोजनविशेषनिर्देशं विनेत्यर्थ इति भावः ॥ **यत्र यत्रेत्यादि ।** यद्यत्प्रयोजनसिद्धिरुद्देश्या तत्तद्विषयसकलप्रयोजनोद्देशेनेत्यर्थः ॥

(भाष्यम्)

किं प्रयोजनम् ?

(५३ सिद्धान्तवार्तिकम् ॥ ३ ॥)

॥ * ॥ अविशेषे संयोगोपधासंज्ञाऽलोन्त्यद्विर्वचनस्थानिवद्भावप्रतिषेधाः ॥ * ॥

(भाष्यम्)

अविशेषेण संयोगसंज्ञा प्रयोजनम् । उश्लकः । "हलोऽनन्तराः संयोगः" इति संयोगसंज्ञा, "संयोगे गुरु" इति गुरुसंज्ञा, "गुरोः—" इति प्लुतो भवति ॥

(प्रदीपः) **उश्लक इति ।** उपध्मानीयस्य जश्त्वे कृते संयोगसंज्ञायां तस्यासिद्धत्वात्संयोगाभावाद्गुरुत्वाभावात् प्लुतो न स्यात् ॥

(उद्द्योतः) **जश्त्वे कृते संयोगसंज्ञायामिति ।** कार्यकालपक्षे इदम् ॥

(प्रयोजनवार्तिकांशव्याख्याभाष्यम्)

उपधासंज्ञा च प्रयोजनम्—दुष्कृतं, निष्कृतं, दुष्पीतं, निष्पीतम् । "इदुदुपधस्य चाप्रत्ययस्य" इति षत्वं सिद्धं भवति ॥

(उद्द्योतः) भाष्ये—इदुदुपधस्येति । विसर्गस्यात्त्वे छुपधात्वमिति भावः ॥

(प्रयोजननिरासभाष्यम्)

नैतदस्ति प्रयोजनम् । न इदुदुपधग्रहणेन विसर्जनीयो विशेष्यते ॥

किं तर्हि ?

सकारो विशेष्यते-इदुदुपधस्य सकारस्य यो विसर्जनीय इति ॥

अथवा—उपधाग्रहणं न करिष्यते, इदुद्भ्यां तु परं विसर्जनीयं विशेषयिष्यामः—इदुद्भ्यामुत्तरस्य विसर्जयनीयस्येति ॥

(उद्द्योतः) इदुदुपधस्य सकारस्येति । विसर्गस्यानुपलक्षणमेतत् । अत एव निरोऽपि निष्कृतमिति सिध्यति । अत एव वक्ष्यमाणपक्षान्तरेणाविरोधः । निष्कृतमित्यादौ सुबुत्पत्तेः पूर्वं समासेऽपि 'इणः षः' इति न । पाशकल्पककाम्येष्वेव तत्प्रवृत्तेः ॥

(प्रयोजनवार्तिकांशव्याख्याभाष्यम्)

अलोऽन्त्यविधिश्च प्रयोजनम्—वृक्षस्तरति, प्लक्षस्तरति । "अलोऽन्त्यस्य" विधयो भवन्तीत्यलोऽन्त्यस्य सत्वं सिद्धं भवति ॥

(प्रयोजननिराकरणभाष्यम्)

एतदपि नास्ति प्रयोजनम् । "निर्दिश्यमानस्यादेशा भवन्ति" इति विसर्जनीयस्यैव भविष्यति ॥

(प्रयोजनवार्तिकांशव्याख्याभाष्यम्)

द्विर्वचनं प्रयोजनम्-उरᳲकः, उरᳲपः । "अनचि च" अच उत्तरस्य यरो द्वे भवत इति द्विर्वचनं सिद्धं भवति ॥

(उद्द्योतः) द्विर्वचनं प्रयोजनमिति । विसर्गजिह्वामूलीयादेर्द्विरुच्चारणे विशेषस्याग्रहात् उच्चारणस्य कर्तुमशक्यत्वाच्च शास्त्रप्राप्तिमात्रेणैतत्प्रयोजनकथनमिति संतोष्टव्यम् ॥

(प्रयोजनवार्तिकांशव्याख्याभाष्यम्)

स्थानिवद्भावप्रतिषेधश्च प्रयोजनम् । यथेह भवति-उरᳲकेण-उरᳲपेणेति "अड्व्यवाय" इति णत्वम्, एवमिहापि स्थानिवद्भावात्प्राप्नोति-व्यूढोरस्केन-महोरस्केनेति । तत्र "अनल्विधौ" इति प्रतिषेधः सिद्धो भवति ॥

(प्रदीपः) महोरस्केनेति । 'पूर्वत्रासिद्धीये न स्थानिवत्' इति निषेधः 'अचः परस्मिन्पूर्वविधौ' इत्यस्य, न तु 'स्थानिवदादेशः' इत्यस्य ॥

(उद्द्योतः) ननु 'सोऽपदादौ' इति सत्वस्य स्थानिवत्त्वं 'पूर्वत्रासिद्धीये' इति निषेधान्नेत्यत आह—पूर्वत्रेति ॥

(इत्ययोगवाहोपदेशाधिकरणम्)

(अथ वर्णार्थवत्ताधिकरणम्)

(वार्तिकावतरणभाष्यम्)

किं पुनरिमे वर्णा अर्थवन्तः, आहोस्विदनर्थकाः ?

(प्रदीपः) इदानीमन्यदपि वर्णगतं वस्तु विचार्यते—किं पुनरिति । पक्षद्वयेऽपि प्रतिवर्णं विभक्त्यनुत्पत्तिज्ञानं विचारस्य प्रयोजनम् ॥

(उद्द्योतः) 'इमे' इत्यनेन न 'हयवरट्'संज्ञा एव गृह्यन्ते, किं तु वर्णमात्रमित्याह—इदानीमिति ॥ 'अर्थवन्तः' इति साध्यम् । 'वर्णाः' इति पक्षः । पक्षतावच्छेदकमेव हेतुः । धातुप्रातिपदिकेत्यादिस्तु दृष्टान्तः ॥ अनुत्पत्तिज्ञानम्-अनुत्पत्त्युपायज्ञानम् ॥

(५४ अर्थवत्तासाधकप्रथमवार्तिकम् ॥ १ ॥)

॥ * ॥ अर्थवन्तो वर्णा धातुप्रातिपदिकप्रत्ययनिपातानामेकवर्णानामर्थदर्शनात् ॥ * ॥

(भाष्यम्)

धातव एकवर्णा अर्थवन्तो दृश्यन्ते—एति, अध्येति, अधीत इति ॥

प्रातिपदिकान्येकवर्णान्यर्थवन्ति—आभ्याम्, एभिः, एषु ॥

प्रत्यया एकवर्णा अर्थवन्तः-औपगवः, कापटवः ॥

निपाता एकवर्णा अर्थवन्तः—अ-अपेहि, इ-इन्द्रं पश्य, उ-उत्तिष्ठ, अ-अपक्राम ।

धातुप्रातिपदिकप्रत्ययनिपातानामेकवर्णानामर्थदर्शनान्मन्यामहे—अर्थवन्तो वर्णाः—इति ॥

(उद्द्योतः) भाष्ये—धातव इत्यादि प्रक्रियाश्रयप्रकृतिप्रत्ययानां वाचकत्वमित्येवंरूपवर्णस्फोटाश्रयेण । अयं च शास्त्रव्यवहारमात्रोपयोगी । एतद्वासनावशादेव लोकव्यवहारेऽपि शास्त्रज्ञास्तथा व्यवहरन्ति, धर्मे चैवंविधज्ञानस्योपयोग इति बोध्यम् ॥

(५५ अर्थवत्तासाधकद्वितीयवार्तिकम् ॥ २ ॥)

॥*॥ वर्णव्यत्यये चार्थान्तरगमनात् ॥*॥

(भाष्यम्)

वर्णव्यत्यये चार्थान्तरगमनान्मन्यामहे-अर्थवन्तो वर्णा इति ।

कूपः सूपो यूप इति ।

कूप इति सककारेण कश्चिदर्थो गम्यते । सूप इति ककारापाये सकारोपजने चार्थान्तरं गम्यते । यूप इति ककारसकारापाये यकारोपजनेऽर्थान्तरं गम्यते । तेन मन्यामहे-यः कूपे कूपार्थः स ककारस्य, यः सूपे सूपार्थः स सकारस्य, यो यूपे यूपार्थः स यकारस्येति ॥

(प्रदीपः) वर्णव्यत्यये-इति । एकस्य वर्णस्याभ्युपगमे-

ऽन्यस्यापगमः=व्यत्ययः ॥ सककारस्येति । तस्यैवान्वयव्यतिरेकावनुविधत्तेऽर्थावसाय इति भावः ॥

(उद्द्योतः) हेत्वन्तरमाह—वर्णव्यत्यये चेति ॥ ननु कूपादौ न सिंहादाविव वर्णव्यत्ययोऽत आह—एकस्येति ॥ तस्यैवान्वयेति । ऊपशब्दस्य तु तदीयशक्त्युद्बोधकत्वरूपं द्योतकत्वं प्रादिवत् । अत एव तेषामिवैषामपि प्रातिपदिकसंज्ञाऽऽपादनं करिष्यते ॥

(५६ अर्थवत्तासाधकतृतीयवार्तिकम् ॥ ३ ॥)

॥ * ॥ वर्णानुपलब्धौ चानर्थगतेः ॥ * ॥

(भाष्यम्)

वर्णानुपलब्धौ चानर्थगतेर्मन्यामहे—अर्थवन्तो वर्णा इति ।

वृक्षः—ऋक्षः, काण्डीरः—आण्डीरः ।

वृक्ष इति सवकारेण कश्चिदर्थो गम्यते, ऋक्ष इति वकारापाये सोऽर्थो न गम्यते । काण्डीर इति सककारेण कश्चिदर्थो गम्यते, आण्डीर इति ककारापाये सोऽर्थो न गम्यते ॥

(प्रदीपः) **वर्णानुपलब्धौ चेति ।** अर्थान्तरावगमात्प्रकृतोऽर्थो न गम्यत इति विवक्षितम् ॥

(उद्द्योतः) तृतीयहेतुमाह—वर्णानुपलब्धौ चेति ॥ 'अनर्थगतेः' इत्यस्य तद्वर्णसत्तायां योऽर्थस्तदर्थानवगतेरित्यर्थ इत्याह— अर्थान्तरेति ॥

(आक्षेपभाष्यम्)

किं तर्ह्युच्यते-'अनर्थगतेः' इति, न साधीयो ह्यत्रार्थस्य गतिर्भवति ?

(प्रदीपः) इतरस्त्वर्थावगत्यभावमात्रमनेनोक्तमिति पृच्छति—**किं तर्हीति ॥ साधीय इति ।** परमतापेक्षया प्रकर्ष आरोप्यते । यथा 'न किंचिदयं तत्र करोति' इत्युक्ते कश्चिदाह—'सुतरामयं करोति' इति ॥

(उद्द्योतः) प्रश्नमुपपादयति—भाष्ये—**न साधीय इति ।** नञि काकुः ॥ **परमतापेक्षयेति ।** परेण 'अनर्थगतेः' इत्युक्तत्वादिहार्थगतिरस्तीत्यभ्युपगम्य परमते कटाक्षेण अन्यसत्तीयार्थगत्यपेक्षयाऽत्यतिशयेनार्थगतिरस्तीति विवक्षेति भावः ॥

(समाधानभाष्यम्)

एवं तर्हीदं पठितव्यं स्यात्-"*वर्णानुपलब्धौ चातदर्थगतेः*" इति ॥

किमिदं—अतदर्थगतेरिति ?

तस्यार्थः-तदर्थः, तदर्थस्य गतिः-तदर्थगतिः, न तदर्थगतिः-अतदर्थगतिः, अतदर्थगतेरिति ॥

अथवा सोऽर्थः-तदर्थः, तदर्थस्य गतिः-तदर्थगतिः, न तदर्थगतिः-अतदर्थगतिः, अतदर्थगतेरिति ॥

(प्रदीपः) **एवं तर्हीति ।** प्रकृतोऽर्थो न गम्यते, अर्थान्तरं तु गम्यत इत्यर्थः ॥ **तस्यार्थ इति ।** वर्णस्य ॥ परं प्रति वर्णानामर्थवत्त्वमसिद्धमिति कथं 'तस्य' इति वर्णः परामृश्यत इत्याह—**सोऽर्थ इति ।** प्रकृतोऽर्थ इत्यर्थः ॥

(उद्द्योतः) तच्छब्दार्थमाह—वर्णस्येति ॥ परे तु तच्छब्देन तद्वर्णघटितपरामर्शे न कश्चिद्दोषः । अत एव पूर्वं भाष्ये 'सककारेण कश्चिदर्थो गम्यते' इत्युक्तमित्याहुः ॥ लाघवेन तु कर्मधारयमाह—भाष्ये—सोऽर्थ इति ॥ प्रकृतोऽर्थः—तस्मिन्वर्णे सति योऽर्थः प्रतीयते स इत्यर्थः ॥

(आक्षेपभाष्यम्)

स तर्हि तथा निर्देशः कर्तव्यः ?

(सिद्धान्तभाष्यम्)

न कर्तव्यः । उत्तरपदलोपोऽत्र द्रष्टव्यः । तद्यथा—उष्ट्रमुखमिव मुखमस्य-उष्ट्रमुखः, खरमुखः । एवमतदर्थगतेः—अनर्थगतेरिति ॥

(प्रदीपः) **उष्ट्रमुख इति ।** गतार्थत्वादप्रयोग एव द्वितीयस्य मुखशब्दस्य लोपोऽभिधीयते । अत्र हि उष्ट्रो मुखमस्येत्येव विग्रहः ॥ न च प्राणी प्राण्यन्तरस्य मुखं भवति—इति विशिष्टावयववृत्तिरुष्ट्रशब्दः सादृश्यान्मुखं विशिनष्टि । एवमिहापि 'अनर्थगतेः' इत्यत्रार्थशब्देन प्रक्रान्तोऽर्थ उच्यते, नार्थमात्रमित्यर्थः ॥

(उद्द्योतः) ननु दृष्टान्ते 'सप्तम्युपमानपूर्व—'इति वचनेनोत्तरपदलोपेऽपि प्रकृते तच्छब्दलोपः केन ? किं च तच्छब्द उत्तरपदमपि न, तच्छब्देन नञः समासाभावादत आह—गतार्थत्वादिति । तथा च तद्वदत्रापि लक्षणेति भावः ॥

(५७ अर्थवत्तासाधकचतुर्थवार्तिकम् ॥ ४ ॥)

॥ * ॥ संघातार्थवत्त्वाच्च ॥ * ॥

(भाष्यम्)

संघातार्थवत्त्वाच्च मन्यामहे—अर्थवन्तो वर्णा इति ।

येषां संघाता अर्थवन्तः, अवयवा अपि तेषामर्थवन्तः । येषां पुनरवयवा अनर्थकाः, समुदाया अपि तेषामनर्थकाः । तद्यथा—एकश्चक्षुष्मान्दर्शने समर्थः, तत्समुदायश्च शतमपि समर्थम् । एकश्च तिलस्तैलदाने समर्थः, तत्समुदायश्च खार्यपि समर्था ॥ येषां पुनरवयवा अनर्थकाः, समुदाया अपि तेषामनर्थकाः । तद्यथा—एकोऽन्धो दर्शनेऽसमर्थः, तत्समुदायश्च शतमप्यसमर्थम् । एका च सिकता तैलदानेऽसमर्था, तत्समुदायश्च खारीशतमप्यसमर्थम् ॥

(उद्द्योतः) चतुर्थहेतुमाह—भाष्ये—सङ्घातार्थवत्त्वाच्चेति । 'एका सिकता' इति भाष्यप्रयोगादेव सिकताशब्दस्यैकवचनान्तत्वमपि ॥

(अर्थवत्तादूषणभाष्यम्)

यदि तर्हीमे वर्णा अर्थवन्तः, अर्थवत्कृतानि प्राप्नुवन्ति ॥

कानि ?

"अर्थवत्प्रातिपदिकम्" इति प्रातिपदिकसंज्ञा । 'प्रातिपदिकात्' इति स्वाद्युत्पत्तिः, 'सुबन्तं पदम्' इति पदसंज्ञा ॥

तत्र को दोषः ?

"पदस्य" इति नलोपादीनि प्राप्नुवन्ति-धनं, वनमिति ॥

(प्रदीपः) नलोपादीनीति । श्रवणं तु विभक्तेर्न भवति, यतो यदैवावयवानां प्रातिपदिकसंज्ञा प्रवर्तते तदैव समुदायस्यापि । तत्र तदन्तर्गतत्वाद्विभक्तेर्लुका भवितव्यम् । समासग्रहणेन च तुल्यजातीयस्य सुबन्तावयवसमुदायस्य प्रातिपदिकसंज्ञा निवार्यते, न त्वर्थवत्समुदायमात्रस्य । येनैव चार्थेन समुदायस्यार्थवत्त्वं तेनैव तदवयवानामपि-इति विभक्त्युत्पत्तिश्चोद्यते ॥

(उद्द्योतः) तदन्तर्गतत्वादिति । इदं चिन्त्यम्, 'इत्थंभूतलक्षणे' इति सूत्रस्थस्वग्रन्थविरोधात् । तत्र हि—संज्ञाप्रवृत्त्युत्तरकालजातविभक्तेस्तन्मध्यपतितत्वेऽपि तदवयवत्वं नेत्युक्तम् । तस्मादन्तरङ्गत्वात्तदवयवप्रातिपदिकत्वे तन्निमित्तसुपि तदन्तरं कृदन्तत्वनिमित्तकप्रातिपदिकत्वे सुप्लोप इति वक्तुं युक्तम् । 'ध्वनति'इत्यादौ तु न तदापत्तिः, धातुप्रत्ययान्तपदयोस्तदवयवपरत्वेन तत्र तदप्राप्तेः । धात्वादेस्तदवयवत्वं तु व्यपदेशिवद्भावेन बोध्यम् । वस्तुतः 'इत्थंभूत-' इति सूत्रस्थकैयटोक्तिरयुक्तेति तत्रैव निरूपयिष्याम इति न दोषः ॥ धकारे जश्त्वं-आदिपदार्थः ॥ सुबन्तावयवसमुदायस्येति । सुबन्तावयवेति बहुव्रीहिस्ततः कर्मधारयः । इदमुपलक्षणम्—भेदे सति यदर्थयोः संसर्गस्तद्द्वारकार्थवत्समुदायस्य, तेन तिङन्तसमुदायस्य व्यावृत्तिः । प्रकृते न भेद इत्याह—येनैव चेति ॥

(वर्णस्यार्थवत्तायां दोषनिराकरणे भाष्यवार्तिकम् ॥)

॥ संघातस्यैकार्थ्यात्सुबभावो वर्णात् ॥

(भाष्यम्)

संघातस्यैकत्वमर्थः, तेन वर्णात्सुबुत्पत्तिर्न भविष्यति ॥

(प्रदीपः) अत्र परिहारमाह—संघातस्येति । वृक्ष इत्यत्रैकत्वं विभक्त्या द्योत्यते । तच्चैकमित्येकैव विभक्तिरुत्पद्यते । यथा–बहवो द्रष्टार एकेनैव प्रदीपेन दृश्यमर्थं पश्यन्ति । सा चोत्पद्यमाना समुदायादेव तन्त्रेण सर्वानुग्राहिण्युत्पद्यते, समुदायाद्विर्वचनवत् । पदसंज्ञा तु समुदायस्यैव भवति न प्रत्येकम्, असुबन्तत्वात् । 'यस्मात् प्रत्ययविधिः' इत्यनुवर्तनात् ॥

(उद्द्योतः) तच्चैकमिति । 'सङ्घातस्यैकत्वम्'इति भाष्यस्य सङ्घातस्याप्येकत्वमर्थः । एवञ्च विभक्तिः समुदायादेवेति भावः ॥ ननु समुदायादुत्पद्यमाना विभक्तिः सर्ववर्णसंबन्धिनी चेत् प्रतिवर्णं पदत्वं प्राप्नोतीत्यत आह—पदसंज्ञा त्विति । यतश्चार्थबोधनाय विभक्त्युत्पत्तिस्तस्य संज्ञा प्रवर्तते, न त्वेषामिति भावः ॥ केचित्तु विभक्तिः प्रकृत्यर्थगतप्रकृतिबोध्यसङ्ख्याद्योतिका । सङ्ख्या च समुदायस्यैवार्थः, न प्रत्येकवर्णानामिति न तेभ्यः स्वाद्युत्पत्तिः । 'एकत्वं सङ्घातस्यार्थः' इति भाष्यस्वरसात् । प्रकृत्यंशे वर्णव्यत्ययापाययोः सङ्ख्यान्तरानुपजननात्सा समुदायस्यैवार्थ इति तद्भावः ॥ न चाव्ययेभ्य एकवचनं दुर्वारम् । सङ्ख्यारहितार्थप्रतिपादकेषु तथास्वीकारेऽपि वस्तुतः सङ्ख्यावत्यर्थे सङ्ख्यानभिधायकस्वाद्युत्पत्तौ मानाभावात् । एवंचैषां प्रकृतित्वमेव नेति 'न केवला प्रकृतिः' इत्यस्यापि न विषयः । एतेन प्रत्येकं पदसंज्ञाऽनुग्रहाय द्विर्वचनवैषम्यात् स्यादेव प्रत्येकं सुबुत्पत्तिरित्यपास्तमित्याहुः ॥

(५८ अनर्थकत्वसाधकप्रथमवार्तिकम् ॥ ५ ॥)

॥ * ॥ अनर्थकास्तु प्रतिवर्णमर्थानुपलब्धेः ॥ * ॥

(भाष्यम्)

अनर्थकास्तु वर्णाः ।

कुतः ?

'प्रतिवर्णमर्थानुपलब्धेः' । न हि प्रतिवर्णमर्था उपलभ्यन्ते ॥

किमिदं प्रतिवर्णमिति ?

वर्णं वर्णं प्रति-प्रतिवर्णम् ॥

(प्रदीपः) अनर्थकास्त्विति । धात्वादिव्यतिरिक्ता वर्णाः पक्षीक्रियन्ते, अन्यथा शास्त्रविरोधः प्राप्नोति ॥ किमिदमिति । असमासशङ्कया प्रश्नः, समासेन तूत्तरम् । तेनैव वीप्सा द्योतिता–इति द्विर्वचनं न भवति ॥

(उद्द्योतः) अनुमानेन साधितामर्थवत्तां प्रत्यक्षविरोधेन दूषयति—अनर्थकास्त्विति ॥ सर्ववर्णानां पक्षत्वे हेतोर्भागासिद्धत्वं स्यादत आह—धात्वादीति ॥ विपक्षे बाधकमाह—अन्यथेति । वर्णव्यत्ययेत्यादिहेतोरर्थानुपलब्धेरिति हेतोश्च धात्वाद्यतिरिक्तवर्णविषयत्वे एव सङ्गतेरित्यपि बोध्यम् ॥ असमासशङ्कयेति । तथा च वीप्सा न प्रतीयेतेति भावः ॥ तेनैवेति । वीप्सायां तस्य विधानादिति भावः ॥

(५९ अनर्थकत्वसाधकद्वितीयवार्तिकम् ॥ ६ ॥)

॥ * ॥ वर्णव्यत्ययापायोपजनविकारेष्वर्थदर्शनात् ॥ * ॥

(भाष्यम्)

वर्णव्यत्ययापायोपजनविकारेष्वर्थदर्शनान्मन्यामहे-अनर्थका वर्णा इति ॥

वर्णव्यत्यये-कृतेस्तर्कः, कसेः सिकताः, हिंसेः सिंहः । वर्णव्यत्ययो नार्थव्यत्ययः ॥

अपायः=लोपः—घ्नंति, घ्नन्तु, अघ्नन् । वर्णापायो नार्थापायः ॥

उपजनः=आगमः—लविता, लवितुम् । वर्णोपजनो नार्थोपजनः ॥

विकारः=आदेशः—घातयति, घातकः । वर्ण-

विकारो नार्थविकारः ॥

यथैव वर्णव्यत्ययापायोपजनविकारा भवन्ति तद्वदर्थव्यत्ययापायोपजनविकारैर्भवितव्यम् । न चेह तद्वत्। अतो मन्यामहे—अनर्थका वर्णा इति ॥

(प्रदीपः) वर्णव्यत्ययेति । यदुक्तम्—*वर्णव्यत्यये चार्थान्तरगमनाद्वर्णानुपलब्धौ चानर्थगतेः* इति, तस्यानैकान्तिकत्वमुद्भाव्यते ॥

(उद्योतः) ननु वर्णव्यत्ययादिष्वर्थदर्शनं नार्थवत्त्वाभावसाधकमत आह—यदुक्तमिति। एवंचार्थवत्त्वसाधकहेतौ व्यभिचारप्रदर्शनद्वाराऽनर्थकतासाधकत्वमस्य ॥ भाष्ये—'अर्थदर्शनात्' इत्यस्य वर्णव्यत्ययाद्यभावे योऽर्थस्तस्यैव दर्शनादित्यर्थः ॥ 'नार्थव्यत्ययः' इत्यस्य नार्थान्तरावगतिः, किं तु तस्यैवावगतिरित्यर्थः ॥

(तटस्थाक्षेपभाष्यम्)

उभयमिदं वर्णेषूक्तम्—अर्थवन्तोऽनर्थका इति च। किमत्र न्याय्यम्?

(समाधानभाष्यम्)

उभयमित्याह ॥

कुतः?

स्वभावतः। तद्यथा-समानमीहमानानां चाधीयानानां च केचिदर्थैर्युज्यन्ते, अपरे न। न चेदानीं कश्चिदर्थवानिति कृत्वा सर्वैरर्थवद्भिः शक्यं भवितुम्, कश्चिद्वाऽनर्थक इति सर्वैरनर्थकैः।

तत्र किमस्माभिः शक्यं कर्तुम्?

यद्धातुप्रत्ययप्रातिपदिकनिपाता एकवर्णा अर्थवन्तः, अतोऽन्येऽनर्थका इति। स्वाभाविकमेतत् ॥

(प्रदीपः) उभयमित्याहेति। यत्रान्वयव्यतिरेकाभ्यामर्थवत्ता शक्यते कल्पयितुं तत्रैवासावभ्युपगन्तव्या, न सर्वत्रेत्यर्थः ॥

(उद्योतः) उभयस्य न्याय्यत्वं विषयभेदेनेत्याह—यत्रान्वयेति। यथा—'एति' 'इतः' इत्यादौ ॥ न सर्वत्र—कूपादावित्यर्थः ॥

(आक्षेपभाष्यम्)

कथं य एष भवता वर्णानामर्थवत्तायां हेतुरुपदिष्टः-'अर्थवन्तो वर्णा धातुप्रातिपदिकप्रत्ययनिपातानामेकवर्णानामर्थदर्शनात् वर्णव्यत्यये चार्थान्तरगमनात् वर्णानुपलब्धौ चानर्थगतेः संघातार्थवत्त्वाच्च' इति?

(समाधानभाष्यम्)

संघातान्तराण्येवैतान्येवंजातीयकानि अर्थान्तरेषु वर्तन्ते—कूपः, सूपः, यूपः—इति।

यदि हि वर्णव्यत्ययकृतमर्थान्तरगमनं स्यात्, भूयिष्ठः कूपार्थः सूपे स्यात्, सूपार्थश्च कूपे, कूपार्थश्च यूपे, यूपार्थश्च कूपे, यूपार्थश्च सूपे। यतस्तु खलु न किंचित्सूपस्य वा यूपे, यूपस्य वा कूपे, कूपस्य वा यूपे, यूपस्य वा सूपे; अतो मन्यामहे—संघातान्तराण्येवंजातीयकान्यर्थान्तरेषु वर्तन्त इति।

इदं खल्वपि—भवता वर्णानामर्थवत्तां ब्रुवता साधीयोऽनर्थकत्वं द्योतितम्। यो हि मन्यते—यः कूपे कूपार्थः स ककारस्य, यः सूपे सूपार्थः स सकारस्य, यो यूपे यूपार्थः स यकारस्येति; ऊपशब्दस्त्वस्यानर्थकः स्यात् ॥

(प्रदीपः) संघातान्तराणीति। तदुक्तं—

'न कूपयूपसूपानामन्वयोऽर्थस्य विद्यते।
ततोऽर्थान्तरवाचित्वं संघातस्यैव गम्यते ॥' इति ॥

(उद्योतः) न कूपयूपेति। वर्णानामर्थवत्त्वे 'ऊप'शब्दस्य त्रिष्वन्वयादर्थान्वयः स्यात्, न च दृश्यते। ततः समुदायान्तरत्वप्रयुक्तमेवार्थान्तरत्वं तदर्थानवगतिश्च, न तु व्यत्ययादिकृतमित्यर्थः ॥ ननु ककारसकारयकाराणामेवार्थवत्त्वम्, ऊपस्तु शक्त्युद्बोधक एव—इति कस्यार्थस्य सत्ता तत्र तत्रापाद्यत इति चेत्; तर्हि भ्रममेव वर्णानामर्थवत्त्वम्, तत्रैव पदे ऊ-पयोरर्थाभावात्। किंच सङ्ख्या समुदायस्यैवार्थ इत्यपि नियन्तुमशक्यं, कूपगतैकत्वस्य यूपादिभिरप्रतीत्या संख्ययाऽपि कादिभिरन्वयव्यतिरेकसत्त्वात्। द्विवंचनेन वैषम्यं तु प्रागुक्तमेव। तस्मात्समुदायस्यैवार्थवत्त्वम्। तदेव ध्वनयन्नाह—भाष्ये—इदं खल्वपीत्यादि ॥

(आक्षेपभाष्यम्)

तत्रेदमपरिहृतम्—*संघातार्थवत्त्वाच्च* इति ॥

(समाधानभाष्यम्)

एतस्यापि प्रातिपदिकसंज्ञायां परिहारं वक्ष्यति ॥

(प्रदीपः) एतस्यापीति। 'दृष्टा ह्यतदर्थेन गुणेन गुणिनोऽर्थवत्ता, सुराऽश्ववद्रथाश्ववच्च—इति ॥

(उद्योतः) दृष्टो हीति। अतदर्थेन रथाश्वेन गुणिनो रथस्य यथाऽर्थवत्ता तथा प्रकृतेऽपीति भावः।

इति वर्णानामर्थवत्ताधिकरणम् ॥

(अथ प्रत्याहारेष्वित्ग्रहणाभावाधिकरणम्)

(सूत्रानुवादभाष्यम्)

अइउण्-ऋऌक्-एओङ्-ऐऔच् ॥

(आक्षेपश्लोकवार्तिकम् ॥ १ ॥)

प्रत्याहारेऽनुबन्धानां कथमज्ग्रहणेषु न ॥

(भाष्यम्)

य एतेऽक्षु प्रत्याहारार्था अनुबन्धाः क्रियन्ते, एतेषामज्ग्रहणेन ग्रहणं कस्मान्न भवति?

किं च स्यात्?

दधि णकारीयति, मधु णकारीयतीति "इको यणचि" इति यणादेशः प्रसज्येत ॥

(उद्योतः) भाष्ये—अज्ग्रहणेष्विति। प्रत्याहारे=अक्षरसमाम्नायेऽज्ग्रहणेषु=अच्प्रत्याहारग्राहकेषु पठितानामनुबन्धानां

प्रत्यासत्त्याऽक्षु ग्रहणं कुतो नेत्यर्थः ॥ तत्फलितार्थमाह—य एते इति । अक्षु=तद्बोधकसूत्रेषु प्रागुक्तेषु ॥ प्रत्याहारार्थाः=तदुपकारकाः ॥ अज्ग्रहणेन=अच्शब्देन ॥ अणगादिप्रत्याहारेषु तेषां ग्रहणे फलाभावं मनसि निधाय 'अज्ग्रहणेन' इत्युक्तम् । न च इशादौ टग्रहणस्यापत्तिः । हल्षु उच्चारणार्थाकारोच्चारणेनोच्चारणार्थवर्णहीनहलां हल्घटितप्रत्याहारे ग्रहणाभावस्य वक्तुं शक्यत्वात् ॥

(सिद्धान्तसमाधानश्लोकवार्तिकखण्डम्)

***आचारात्,**

(भाष्यम्)

किमिदमाचारादिति ?

आचार्याणामुपचारात् । नैतेष्वाचार्या अच्कार्याणि कृतवन्तः ॥

(प्रदीपः) **आचारादिति** । आचारः=व्यवहारः । '**तृषिमृषिकृषेः—**' इति गण् न कृतः ॥

(सिद्धान्तसमाधानश्लोकवार्तिकखण्डम्)

***अप्रधानत्वात्,**

(भाष्यम्)

अप्रधानत्वाच्च । न खल्वप्येतेषामक्षु प्राधान्येनोपदेशः क्रियते ।

क्व तर्हि ?

हल्षु ।

कुत एतत् ?

एषा ह्याचार्यस्य शैली लक्ष्यते—यत्तुल्यजातीयांस्तुल्यजातीयेषूपदिशति—अचोऽक्षु हलो हल्षु ॥

(प्रदीपः) **अप्रधानत्वादिति** । 'प्रधानाप्रधानसंनिधौ प्रधानमेव कार्याणां प्रयोजकं' इति परार्थानामनुबन्धानामच्संज्ञा न प्रवर्तत इत्यर्थः ॥ **शैलीति** । शीले भवा—**शैली**=समाधानपूर्विका प्रकृतिः । यथा-लोके ब्राह्मणैः सह ब्राह्मणा भोज्यन्ते क्षत्रियैः सह क्षत्रिया इति, एवमिहापि वर्णा आचार्येण निर्दिष्टा इत्यर्थः ॥

(उद्द्योतः) (भाष्ये) प्राधान्येन-प्रत्याहारेषु ग्रहणार्थत्वेन ॥ **परार्थेति** । अजादिस्वरूपबोधनार्थत्वेन **परार्थत्वम्** । यथा-अकारादयः संज्ञिविशेषसमर्पणायोपात्ताः, न तथा णादय इत्यर्थः ॥ अप्रधानत्वमप्याचार्याचारेण साधयति—भाष्ये—**आचार्यस्येति** । आचार्यशब्देन-अनादिः शब्दपुरुषः । एवंचान्यत्र संज्ञिविशेषसमर्पणायोपात्तत्वादितामसञ्ज्ञित्वमेवेति भावः ॥

(सिद्धान्तसमाधानश्लोकवार्तिकखण्डम् ॥)

***लोपश्च बलवत्तरः ॥ १ ॥**

(भाष्यम्)

लोपः खल्वपि तावद्भवति ॥

(प्रदीपः) **लोपश्चेति** । परत्वान्नित्यत्वाद्वा 'आदिरन्त्येन सहेता' इत्यनेनाच्संज्ञाविधानकालेऽनुबन्धानां लोपादसन्निधानादच्संज्ञा न प्रवर्तते । अनुबन्धा ह्युच्चारण एव सन्ति, इत्संज्ञाप्रतिबद्धं च कार्यमसन्त एव प्रतिपादयन्ति, स्वतस्तु न किंचित्कार्यं प्रतिपद्यन्ते ॥

(उद्द्योतः) '**परत्वात्**'इत्याद्यन्तरङ्गत्वोपलक्षणम् । एवञ्च पूर्वमनुबन्धलोपात् '**आदिरन्त्येन—**' इति संज्ञाविधानकालेऽसंनिधानादित्यन्वयः । एवञ्चानुबन्धसदृशभिन्नानामेव मध्यगसदृशानां ग्राह्यतां बोधयतीति भावः ॥ भाष्ये—**लोपः खल्वपि तावदिति** । सर्वतः प्रथममित्यर्थः ॥ यत्तु एवमपि 'लण्'इत्यकारस्य हल्षु ग्रहणापत्तेः '**आचारात्**'इत्येव समाधिरत्र युक्त इति । तन्न, '**अतो ल्रान्तस्य**' इति सूत्रे लकारोच्चारणेन 'लण्'सूत्रस्थस्यानुनासिकत्वाभावज्ञापनात् । एवञ्च तस्यानुबन्धत्वमेव न, किन्तूच्चारणार्थत्वमेव । अत एव भाष्ये 'अइउण्' इत्यादिसूत्रचतुष्टयोपादानेनैवैतद्विचारप्रवृत्तिः कृता । श्लोके च 'अज्ग्रहणेषु'इत्येवोक्तम् । उरण्रपरसूत्रे च लपरत्वस्योपसंख्यानमेव कार्यमिति तुल्यास्यसूत्रे वक्ष्यते ॥

(सिद्धान्तसमाधानरीत्यन्तरश्लोकवार्तिकम्)

***ऊकालोऽजिति वा योग-**
स्तत्कालानां यथा भवेत् ।
अचां ग्रहणमच्कार्यं
तेनैषां न भविष्यति ॥ २ ॥

(भाष्यम्)

अथवा योगविभागः करिष्यते—"ऊकालोऽच्"

उ-ऊ-उ३ इत्येवंकालोऽज्भवति । ततः—ह्रस्वदीर्घप्लुतसंज्ञश्च भवति—ऊकालोऽच् ॥

(प्रदीपः) **ऊकालोऽजिति** । सिद्धेऽच्त्वे योगविभागेन कालविशेषावच्छिन्नस्याच्त्वं नियम्यते, ततोऽनुबन्धानामूकालत्वाभावादच्त्वाभावः ॥

(उद्द्योतः) भाष्ये—'तत्कालानामचां ग्रहणमच्पदेन यथा स्यात्-इति योगविभागः कार्यः' इत्यन्वयः ॥ **सिद्धेऽच्त्व इति** । अकारादीनामुपदेशात्सवर्णग्रहणाच्चेति भावः ॥

(आक्षेपभाष्यम्)

एवमपि 'कुक्कुटः' इत्यत्रापि प्राप्नोति ॥

(प्रदीपः) **एवमपीति** । ककाराकृतेरुपदेशान्मात्रिकत्वं मन्यते ॥

(उद्द्योतः) ननु ककारद्वयस्य मात्रिकवर्णत्वं कथम्, एकस्यैव फलमित्यत्रोपदेशात्-अत आह—ककाराकृतेरिति ॥

(समाधानभाष्यम्)

तस्मात्पूर्वोक्त एव परिहारः ॥

(प्रदीपः) अत्र च यद्यप्ययं परिहारोऽस्ति-'द्वावेतौ ककारौ, न च वर्णद्वयेनैका जातिर्व्यज्यते' इति, तथापि पूर्वमेव

'मात्राकालोऽत्र गम्यते । न च मात्रिकं व्यञ्जनमस्ति' इत्युक्तत्वात्पुनरिह नोक्तः ॥

(उद्योतः) न च वर्णद्वयेनेति । जातिरपि स्वपर्याप्त्यधिकरणव्यक्त्यैव तद्द्वारैव कार्यभागिति भावः ॥

(भाष्यम्)

एष एवार्थः—

(श्लोकवार्तिकम् ॥)

अपर आह—

*ह्रस्वादीनां वचनात्
प्राग्यावत्तावदेव योगोऽस्तु ।
अच्कार्याणि यथा स्यु-
स्तत्कालेष्वक्षु कार्याणि ॥ ३ ॥

(उद्योतः) भाष्ये—एष एवार्थ इति । 'अपर आह' इत्यादिना वार्तिककृतोक्त इत्यर्थः ॥ ह्रस्वादीनामिति । 'ह्रस्वदीर्घप्लुतः' इत्यतः प्राक् यावत् 'ऊकालोऽच्' इति, तावदेवास्तु पृथक्सूत्रम् । फलं दर्शयति—अच्कार्याणीति । अज्निमित्तकार्याणि तत्कालेष्वक्षु कर्तुमर्हाणि यथा स्युः–इत्यन्वयः ॥

(इति प्रत्याहारेष्विङ्ग्रहणाभावाधिकरणम् ॥)

(अन्तःस्थोपदेशाधिकरणम् ॥)

(आक्षेपभाष्यम्)

अथ किमर्थमन्तःस्थानामण्सूपदेशः क्रियते ?

(प्रदीपः) अथ किमर्थमिति । 'अणुदित्सवर्णस्य' इति कस्मात्र कृतमिति प्रश्नः ॥ इण्ग्रहणेन ग्रहणार्थस्त्वन्तःस्थानामत्रावश्यकर्तव्य उपदेशः 'गीर्षु' इत्यादौ मूर्धन्यो यथा स्यादिति ॥

(उद्योतः) अणः सूपदेशः—अण्सूपदेशः=अण्शब्दोच्चारणम्, तदन्तःस्थानां बोधकं 'अणुदित्–' इत्यत्र किमर्थं क्रियत इत्यर्थो भाष्यस्येत्याह—अणुदिदिति ॥ 'अण्सु=अण्मध्ये, तेनात्र स्थाने किमर्थं उपदेशः' इति तु नार्थ इत्याह—इण्ग्रहणेनेति ॥

(समाधानभाष्यम्)

इह–सय्यँन्ता, सव्ँवत्सरः, यल्ँलोकं, तल्ँलोकमिति परसवर्णस्यासिद्धत्वादनुस्वारस्यैव द्विर्वचनम् । तत्र परस्य परसवर्णे कृते तस्य यण्ग्रहणेन ग्रहणात् पूर्वस्यापि परसवर्णो यथा स्यात् ॥

(उद्योतः) 'इह सय्यँन्ता' इत्यादिभाष्यं 'गुणा भेदकाः' इति पक्षे । भेदकत्वपक्षे चेदमेवाण्ग्रहणं मानमिति भावः । यथास्थितसूत्रन्यासे इदम् । जातिपक्षेणाण्ग्रहणप्रत्याख्याने तु न कश्चिद्विचारः । एवं 'गुणा अभेदकाः' इति न्याय्यपक्षेऽपि न विचार इति बोध्यम् ॥

(समाधानबाधकभाष्यम्)

नैतदस्ति प्रयोजनम् । वक्ष्यत्येतत्—*द्विर्वचने परसवर्णत्वं सिद्धं वक्तव्यम्* इति, यावता सिद्धत्वमुच्यते परसवर्ण एव तावद्भवति ॥

(उद्योतः) भाष्ये—वक्ष्यत्येतदिति । सिद्धत्ववचनं चावश्यकम् । अन्यथा परस्यानुस्वारस्य 'वा पदान्तस्य' इति परसवर्णे तस्यासिद्धत्वात्पूर्वस्य 'अनुस्वारस्य ययि–' इत्यस्याप्राप्तौ रूपासिद्ध्यापत्तेः ॥

(समाधानसाधकभाष्यम्)

परसवर्णे तर्हि कृते तस्य यण्ग्रहणेन ग्रहणाद्द्विर्वचनं यथा स्यात् ॥

(उद्योतः) तर्हि द्विर्वचनसिद्धिरेव फलमित्याह—परसवर्णे तर्हीति ॥

(समाधानबाधकभाष्यम्)

मा भूत् द्विर्वचनम् ॥

(समाधानसाधकभाष्यम्)

ननु च भेदो भवति—सति द्विर्वचने त्रियकारम्, असति द्विर्वचने द्वियकारम् ॥

(प्रदीपः) ननु च भेद इति । श्रुतिकृतोऽस्त्येव भेदः, सूक्ष्मत्वात्तु दुर्लक्ष्यः ॥

(उद्योतः) ननु न भेदः, अनुपलब्धेरत आह—श्रुतिकृत इति ॥

(समाधानबाधकभाष्यम्)

नास्ति भेदः, सत्यपि द्विर्वचने द्वियकारमेव ॥ कथम् ?

"हलो यमां यमि लोपः" इत्येवमेकस्य लोपेन भवितव्यम् ॥

(समाधानसाधकभाष्यम्)

एवमपि भेदः । सति द्विर्वचने कदाचिद्द्वियकारम्, कदाचित् त्रियकारम् । असति द्वियकारमेव ॥

स एष कथं भेदो न स्यात् ?

यदि नित्यो लोपः स्यात् । विभाषा च स लोपः ॥

(उद्योतः) [भाष्ये] यदि नित्यो लोपः स्यादिति । तदा भेदो न स्यादित्यर्थः ॥ विभाषा चेति । चस्त्वर्थे ॥

(समाधानबाधकैकदेशिभाष्यम्)

यथाऽभेदस्तथाऽस्तु ॥

(उद्योतः) एकदेश्याह—यथाऽभेद इति । यथा द्विर्वचनप्रवृत्त्यप्रवृत्त्योर्भेदो न भवति, तथैवास्तु । माऽनुवृतत् विभाषाग्रहणमिति भावः ॥

(समाधानसाधकसिद्धान्तिश्लोकवार्तिकम् ॥)

*अनुवर्तते विभाषा,
शरोऽचि यद्बाधयत्ययं द्वित्वम् ॥

(भाष्यम्)

यदयं "शरोऽचि" इति द्विर्वचनप्रतिषेधं शास्ति, तज्ज्ञापयत्याचार्यः—अनुवर्तते विभाषेति ॥

(उद्योतः) तृतीयो ज्ञापकमुपन्यस्यति—अनुवर्तत इत्यादिना । 'झरो झरि' इति लोपे–इत्यर्थः । मध्यस्थतया 'हलो यमां' इत्यस्यापि वैकल्पिकत्वं सिद्धमिति भावः ॥

(जिज्ञासाभाष्यम्)

कथं कृत्वा ज्ञापकम् ?

(तस्यैव हेतुसूचकमुत्तरार्धम्)

*नित्ये हि तस्य लोपे प्रतिषेधार्थो न कश्चित्स्यात् ॥ १ ॥

(भाष्यम्)

यदि नित्यो लोपः स्यात्, प्रतिषेधवचनमनर्थकं स्यात्। अस्त्वत्र द्विर्वचनम्, "झरो झरि सवर्णे" इति लोपो भविष्यति। पश्यति त्वाचार्यः—विभाषा स लोप इति, ततो द्विर्वचनप्रतिषेधं शास्ति ॥

(समाधानबाधकभाष्यम्)

नैतदस्ति ज्ञापकम्। नित्येऽपि तस्य लोपे स प्रतिषेधोऽवश्यं वक्तव्यः। यदेतत्-"अचो रहाभ्याम्" इति द्विर्वचनम्, लोपापवादः स विज्ञायते ॥

कथम् ?

यर इत्युच्यते। एतावन्तश्च यरः—यदुत झरो वा यमो वा। यदि चात्र लोपः स्याद्द्विर्वचनमनर्थकं स्यात् ॥

किं तर्हि तयोर्योगयोरुदाहरणम् ?

यदकृते द्विर्वचने त्रिव्यञ्जनः संयोगः—प्रत्तम्, अवत्तम्, आदित्यः ॥

इहेदानीं कर्त्ता-हर्त्तेति द्विर्वचनसामर्थ्याल्लोपो न भवति। एवमिहापि लोपो न स्यात्—कर्ष्वेति-वर्ष्वेतीति। तस्मान्नित्येऽपि लोपेऽवश्यं स प्रतिषेधो वक्तव्यः ॥

(उद्द्योतः) लोपापवाद इति। यद्यपि 'दुर्यनुभवः' इत्यादौ तदुदाहरणे लोपेऽप्राप्तेऽपि द्विर्वचनमारभ्यते तथापि कृते द्वित्वे पश्चाल्लोपेऽपि द्विर्वचनं व्यर्थमित्याशयेनापवादत्वोक्तिरिति भावः ॥

तयोर्योगयोः-लोपविधायकयोः ॥ 'प्रत्तं' इत्यादौ दाधातोः क्ते आतस्तकारः 'अच उपसर्गात्-' इत्यनेन। आदित्ये-आदित्याद्भ्वाद्यर्थण्यान्तात् ण्यः ॥

(उपसंहारभाष्यम्)

तदेतदत्यन्तसंदिग्धमाचार्याणां वर्तते—विभाषानुवर्तते न वेति ॥ ५ ॥

(प्रदीपः) तदेतदिति। ज्ञापकत्वमस्य विघटयति ॥ आचार्योपदेशपारम्पर्यात्तु ज्ञायते—'अनुवर्तते विभाषा' इति। तस्मात्त्रिव्यञ्जनसंयोगश्रवणाय 'अणुदित्—' इति णकारेण प्रत्याहारः कृतो न चकारेणेति स्थितम् ॥ ५ ॥

(उद्द्योतः) तद्व्याचष्टे—ज्ञापकत्वमस्य विघटयतीति। सर्वथा 'असंभवी' इत्युपसंहरतीत्यर्थः ॥ ज्ञापकेन तदनुवृत्तिं साधय तस्तत्खण्डनेऽनुवृत्तिः संदिग्धैवेति भावः ॥ 'लण्'सूत्रे 'विभाषा स लोपः' इत्युक्तेराह—आचार्येति। अण्ग्रहणाज्ज्ञापकादित्यपि कश्चित्। तत्तु वार्तिककृताण्ग्रहणप्रत्याख्यानान्नोक्तम् ॥ ५ ॥

(इत्यन्तःस्थोपदेशाधिकरणम्)

(शिवसूत्रम्)

॥ लण् ॥ ६ ॥

(व्याख्यानत इति परिभाषाऽधिकरणम्)

(आक्षेपभाष्यम्)

अयं णकारो द्विरनुबध्यते—पूर्वश्चैव परश्च। तत्राण्ग्रहणेष्विण्ग्रहणेषु च संदेहो भवति—पूर्वेण वा स्युः, परेण वेति ॥

(प्रदीपः) लण् ॥ ६ ॥ संदेहो भवतीति। किं प्रत्यासत्तिराश्रीयते, अथवा व्याप्तिरिति संदेहः ॥

(उद्द्योतः) लण् ॥ ६ ॥ किमिति। क प्रत्यासत्तिः, क व्याप्तिः-इति सन्देह इत्यर्थः ॥

(प्रत्याक्षेपभाष्यम्)

कतमस्मिंस्तावदण्ग्रहणे संदेहः ?

(उद्द्योतः) भाष्ये—कतमस्मिन्निति। वक्ष्यमाणरीत्या सर्वत्र निर्णायकसत्त्वात्प्रश्नः ॥ 'कतरस्मिन्' इति पाठेऽपि डतरादिविधौ उपाधिप्रत्याख्यानान्न दोष इति बोध्यम् ॥

(सन्देहोदाहरणभाष्यम्)

"ढ्रलोपे पूर्वस्य दीर्घोऽणः" (६।३।१११) इति ॥

(सिद्धान्तिनः समाधानश्लोकवार्तिकम्)

*असन्दिग्धं

(भाष्यम्)

पूर्वेण, न परेण ॥

(हेत्वाक्षेपभाष्यम्)

कुत एतत् ?

(सिद्धान्त्येकदेशिहेतुश्लोकवार्तिकम्)

*पराभावात्

(भाष्यम्)

न हि ढ्रलोपे परेऽणः सन्ति ॥

(उद्द्योतः) न हि ढ्रलोप इति। 'वढा' इत्यादौ गुणोऽसिद्ध इति भावः ॥

(हेतुनिरासभाष्यम्)

ननु चायमस्ति—आतृढः, आवृढः-इति ॥

(सिद्धान्तिसमाधानभाष्यम्)

एवं तर्हि-सामर्थ्यात्पूर्वेण, न परेण। यदि हि परेण स्यादण्ग्रहणमनर्थकं स्यात्, "ढ्रलोपे पूर्वस्य दीर्घोऽचः" इत्येव ब्रूयात् ॥

अथवा— एतदपि न ब्रूयात्, अचो ह्येतद्भवति-ह्रस्वः-दीर्घः-प्लुत इति ॥

(उद्द्योतः) दीर्घोऽच इत्येवेति। मात्राकालस्याभावेऽप

संग्राहलाघवायासंदेहाय चेति भावः ॥ [भाष्ये—अचो हीति । 'अचश्च' इति परिभाषणादिति भावः ॥]

(द्वितीयं सन्देहोदाहरणभाष्यम्)

अस्मिंस्तर्ह्यण्ग्रहणे संदेहः-"केऽणः" इति ॥

(समाधानभाष्यम्)

असंदिग्धं पूर्वेण, न परेण ।

कुत एतत् ?

पराभावात् ।

न हि के परेऽणः सन्ति ॥

(प्रदीपः) **न हि के पर इति** । नन्वल्पोपानत्—उपानत्का-इति ह्रस्वे कर्तव्ये **'नहो धः'** इत्यस्यासिद्धत्वादस्ति के परतो हकारः, तथा 'गीष्का' इत्यादौ रेफः ॥

अत्राहुः—'न मु ने' इत्यत्र योगविभागेन धत्वादीनामसिद्धत्वाभावात्तेषु च कृतेषु हकारादीनामभावः ॥

(उद्योतः) तथा गीष्केति । विसर्गस्यासिद्धत्वादिति भावः ॥ तेषु च कृतेष्विति । परत्वादिति भावः । योगविभागस्य भाष्यानारूढत्वात्-'गोका' इत्यादिभाष्यात्-'के परे' इति भाष्याच्च तेषामनभिधानं वक्तुं युक्तम् ॥

(हेतुनिरासभाष्यम्)

ननु चायमस्ति—गोका, नौकेति ॥

(सिद्धान्तिभाष्यम्)

एवं तर्हि—सामर्थ्यात्पूर्वेण, न परेण । यदि हि परेण स्यादण्ग्रहणमनर्थकं स्यात्, "केऽचः" इत्येव ब्रूयात् । अथवा—एतदपि न ब्रूयात्, अचो ह्येतद्भवति ह्रस्वो दीर्घः प्लुत इति ॥

(तृतीयं सन्देहोदाहरणभाष्यम्)

अस्मिंस्तर्ह्यण्ग्रहणे सन्देहः—"अणोऽप्रगृह्यस्यानुनासिकः" इति ॥

(समाधानभाष्यम्)

असंदिग्धं पूर्वेण, न परेण !

कुत एतत् ?

पराभावात् । न हि पदान्ताः परेऽणः सन्ति ॥

(प्रदीपः) **न हि पदान्ता इति** । ननु **'भोभगो'** इत्यत्राण्ग्रहणस्य प्रयोजनं वक्ष्यते-वृक्षव् करोतीत्यत्र **'हलि सर्वेषाम्'** इति लोपो मा भूदिति, तत्कथमुच्यते-'न हि पदान्ताः' इति । उच्यते—**'अप्रगृह्यस्य'** इति पर्युदासेनाच एवानुनासिकेन भाव्यं न तु हल इत्युक्तं—**न हि पदान्ता इति** । कार्यभाज इत्यर्थः ॥

(उद्योतः) न हि पदान्ता इति । पदानामेवानुनासिकोऽवसाने जायत इत्याश्रित्येदमुक्तम् । न तु तत्र पदान्ताधिकारोऽस्ति ॥ लोप इति । अत्रा हलो विशेषणादिति भावः ॥

पर्युदासेनेति । क्रियमाणेऽप्यण्ग्रहणे-इत्यर्थः ॥ भाष्येऽपि न सत्त्वं निषिध्यते, किं तु कार्यित्वमेवेत्याह—**कार्यभाज इति** । एवं चानुनासिकप्राप्तियोग्याः पदान्ता न सन्तीत्यर्थः ॥ वस्तुतोऽस्याग्रे सिद्धान्त्युक्तित्वेन तदज्ञानेनैव पूर्वपक्षस्यौचित्येनैवं भाष्यव्याख्यानमनुचितं, पूर्वपक्षस्य संदेहस्य चानुत्थानात् । तस्मादष्टमाध्यायस्थं भाष्यमेकदेश्युक्तिरित्येवोचितम् । व्याख्यातं च तत्रोपाध्यायैरित्थमेव ॥

(हेतुनिरासभाष्यम्)

ननु चायमस्ति—कर्तृ, हर्तृ ॥

(उद्योतः) भाष्ये—कर्तृ हर्त्रिति । एषामप्युपलक्षणम् । अत एव 'अचोऽप्रगृह्यस्य' इत्युक्तम् । अन्यथा 'अकोऽप्रगृह्यस्य' इति वदेत् ॥

(सिद्धान्तिभाष्यम्)

एवं तर्हि—सामर्थ्यात्पूर्वेण, न परेण । यदि हि परेण स्यात्, अण्ग्रहणमनर्थकं स्यात् । "अचोऽप्रगृह्यस्यानुनासिकः" इत्येव ब्रूयात् ।

अथवा—एतदपि न ब्रूयात् । अच एव हि प्रगृह्या भवन्ति ॥

(प्रदीपः) **अचोऽप्रगृह्यस्येति** । हलो हि न भाव्यमिति-अत्र 'अण्'ग्रहणसामर्थ्यात्पूर्वेणेति स्थितम् ॥ तत्र वृक्षं वृश्चतीति क्विपि कृते वृक्षवृश्चमाचष्टे-इति णिचि टिलोपे च कृते वृक्षवयतेर्विचि 'वृक्षव्' इति भवति । क्विपि तु **'क्वौ लुप्तं-कौ विधिं प्रति च न स्थानिवत्'** इति निषेधात्संप्रसारणप्रसङ्गः, **'लोपो व्योर्वलि'** इति वलोपप्रसङ्गश्च । विचि तु स्थानिवद्भावाद्धल्निमित्तो वलोपो न भवति । **'हलि सर्वेषां'** इत्यनेन तु लोपे क्रियमाणे **पूर्वत्रासिद्धे न स्थानिवत्'** इति स्थानिवत्त्वनिषेधाद्वलोपः प्राप्तोऽण्ग्रहणानुवृत्त्या निवर्त्यते ॥

(उद्योतः) **निषेधात्संप्रसारणप्रसङ्ग इति** । चिन्त्यमिदम् । णौ परतस्तत्प्रकृतिभूतप्रातिपदिकस्य टिलोपविधानेन वृश्चतेः स्थानित्वे मानाभावेन वकारे **एकदेशविकृतन्यायेन** वृश्चतित्वस्य दुर्लभत्वात् । अर्थाधिकविकारेण प्रत्यभिज्ञाऽभावाच्च । अत एव राजकीयमित्यादौ अल्लोपो न । अत एव टिलोपस्यानित्वे तु प्रकृतिभावापत्तिः । **एतेन** विचि **एकदेशविकृतन्यायेन** वृश्चतित्वात्षत्वापत्तिः । न च णिलोपस्य स्थानिवत्त्वान्न षत्वम् । पूर्वत्रासिद्धीये तन्निषेधादिति **परास्तम्** । न च 'व्रश्च-' इति सूत्रे पदाधिकारेण व्रश्चान्तत्वमेकदेशविकृतन्यायेन सुलभमिति वाच्यम् । **'स्कोः-'** इति सूत्रात् 'अन्ते' ग्रहणमनुवर्त्य वैयधिकरण्येनैवान्वयाश्रयणेनादोषात् । अत एव **'अन्ते'** ग्रहणं चरितार्थम् । अर्थाधिकविकाराच्च । एवं च वृक्षभृज्जो णिजन्तात्क्विपि **'वृक्षभ्'** इत्यादौ षत्वं नेत्याहुः ॥ **वलोपप्रसङ्गश्चेति** । इदमुपलक्षणं क्वौ विधौ स्थानिवत्त्वनिषेधादूठ्प्रसङ्गश्चेत्यपि बोध्यम् ॥

(चतुर्थसंदेहभाष्यम्)

अस्मिंस्तर्ह्यण्ग्रहणे संदेहः-"उरण् रपरः" इति ॥

(समाधानभाष्यम्)

असंदिग्धं पूर्वेण, न परेण ॥

कुत एतत् ?

पराभावात् ।

न ह्युः स्थाने परेऽणः सन्ति ॥

(हेतुनिरासभाष्यम्)

ननु चायमस्ति-कर्त्रर्थं, हर्त्रर्थमिति ।

(आपत्तिप्रश्नभाष्यम्)

किं च स्यात्—यद्यत्र रपरत्वं स्यात् ?

(आपत्तिदर्शनभाष्यम्)

द्वयो रेफयोः श्रवणं प्रसज्येत ॥

(आपत्तिबाधकभाष्यम्)

"हलो यमां यमि लोपः" इत्येवमेकस्यात्र लोपो भविष्यतीति ॥

(आपत्तिसाधकभाष्यम्)

विभाषा स लोपः, विभाषाश्रवणं प्रसज्येत ॥

(आपत्तिबाधकभाष्यम्)

अयं तर्हि नित्यो लोपः—"रो रि" इति ॥

(उद्द्योतः) भाष्ये—रो रीति । त्रिपाद्यां बहिरङ्गासिद्धत्वाभावादिति भावः ॥

(आपत्तिसाधकभाष्यम्)

'पदान्तस्य' इत्येव सः ॥

(आपत्तिबाधकभाष्यम्)

न शक्यः सः 'पदान्तस्य' इत्येव विज्ञातुम् । इह हि लोपो न स्यात्-जर्गृधेर्लङ्-अजर्घाः-इति ॥

(प्रदीपः) अजर्घा इति । गृधेर्यङ्लुकि रुगागमेऽभ्यासस्य कृते लङि सिपि शब्लुकि गुणरपरत्वसिलोपभष्भावजश्त्वरुत्वरलोपदीर्घत्वेषु रूपम् ॥

(उद्द्योतः) भष्भावः—'एकाचो बशो भष्' इत्यनेन । तत्र हि 'एकाचः' इति 'झषन्तस्य' इति च 'धातोः' इत्यपेक्षया व्यधिकरणषष्ठीति भावः ॥ रुत्वम्—दश्चेत्यनेन ॥

(आपत्तिसाधकभाष्यम्)

इह तर्हि-मातॄणां-पितॄणामिति रपरत्वं प्रसज्येत ॥

(आपत्तिबाधकभाष्यम्)

आचार्यप्रवृत्तिर्ज्ञापयति-नात्र रपरत्वं भवतीति । यदयम् "ऋत इद्धातोः" इति धातुग्रहणं करोति ॥

कथं कृत्वा ज्ञापकम् ?

धातुग्रहणस्यैतत्प्रयोजनम्-इह मा भूत्-मातॄणां पितॄणामिति । यदि चात्र रपरत्वं स्याद्धातुग्रहणमनर्थकं स्यात् । रपरत्वे कृतेऽनन्त्यत्वादित्वं न भविष्यति । पश्यति त्वाचार्यः—नात्र रपरत्वं भवतीति । ततो धातुग्रहणं करोति ॥

(आपत्तिसाधकभाष्यम्)

इहापि तर्हि न प्राप्नोति-चिकीर्षति-जिहीर्षतीति ॥

(प्रदीपः) इहापि तर्हीति । धातुग्रहणेन हि लिङ्गेनाधातोरेव रपरत्वं निवर्तितम् । धातोस्तु रपरत्वे सत्यनन्त्यत्वान्न प्राप्नोतीति प्रश्नः ॥

(उद्द्योतः) भाष्ये—'इहापि तर्हि' इत्यस्य 'ऋत इत्वं' इति शेषः ॥ ननु धातुग्रहणेन ऋकारस्य दीर्घो न रपर इति ज्ञापनात् 'अज्झन-' इति दीर्घस्याप्यरपरत्वात् कथमत्रेत्वाप्राप्तिरत आह—धातुग्रहणेनेति ॥

(आपत्तिबाधकभाष्यम्)

मा भूदेवम् । "उपधायाश्च" इत्येवं भविष्यति ॥

(आपत्तिसाधकभाष्यम्)

इहापि तर्हि प्राप्नोति-मातॄणामिति ॥ तस्मात्तत्र धातुग्रहणं कर्तव्यम् ॥

(प्रदीपः) इहापीति । तस्माद्धातुग्रहणस्य प्रयोजनवत्त्वान्न ज्ञापकत्वमित्यर्थः ॥

(उद्द्योतः) भाष्ये—तस्मात्तत्रेति । न च 'इह किंचित्क्रियमाणं ज्ञापकं भवति' इति न्यायेन ज्ञापकत्वमप्यस्त्विति वाच्यम् । 'गॄ'इत्यादेरनुकरणे प्रकृतिवदनुकरणमित्यस्याभावे'ग्रो यङि'इत्यादावित्वाभावार्थमिहापि तदावश्यकत्वात् । गत्यन्तराभावे एव तन्न्यायेन ज्ञापकत्वाश्रयणाच्च । तदाह—तस्मादिति । एवंच रपरत्वेऽपि मातॄणामित्यादौ 'उपधायाश्च' इतीत्त्ववारणेन धातुग्रहणस्य चारितार्थ्येन रपरत्वनिवृत्तौ न ज्ञापकतेत्यर्थः ॥

(सिद्धान्तिसमाधानभाष्यम्)

एवं तर्हि-सामर्थ्यात्पूर्वेण, न परेण । यदि हि परेण स्यात्, अण्ग्रहणमनर्थकं स्यात् "उरश्रपरः" इत्येव ब्रूयात् ॥

(उद्द्योतः) भाष्ये—सामर्थ्यात्पूर्वेणेति । न च 'गम्ला' इत्यादौ यणादेशे लपरत्वार्थमेव परेणाण्ग्रहणं स्यादिति सामर्थ्यं कथम् ? ऋकारांशे हलरूपाणि 'रो रि' इति प्रवृत्त्या फलाभावेन तत्साहचर्यात् लृकारांशेऽपि हलरूपाणि अप्रवृत्तिरित्याशयात् । रलयोः समानश्रुतित्वेन तत्रापि 'रो रि' इत्यस्य प्रवृत्तेरित्यन्ये ॥ लकारे यण्घटितप्रयोगानभिधानमेवैतद्भाष्यप्रामाण्यादित्यन्ये ॥

(पञ्चमसन्देहभाष्यम्)

अस्मिंस्तर्ह्यण्ग्रहणे संदेहः—"अणुदित्सवर्णस्य चाप्रत्ययः" इति ॥

(समाधानभाष्यम्)

असंदिग्धं परेण, न पूर्वेण ॥

(हेत्वाक्षेपभाष्यम्)

कुत एतत् ?

(सिद्धान्तश्लोकवार्तिकम्)

*सवर्णेऽण् तपरं ह्युकृत् ॥

(भाष्यम्)

यदयम्—"उकृत्" इत्यृकारे तपरकरणं करोति, तज्ज्ञापयत्याचार्यः—परेण, न पूर्वेणेति ॥

(प्रदीपः) सवर्णे इति । 'अचीकृतत्' इति ऋकारस्य ऋकार एव यथा स्यात्, ॠकारो मा भूदित्येवमर्थं तपरत्वं क्रियते । यदि च पूर्वेण णकारेणाण्ग्रहणं स्यात् ऋकारोऽनण्त्वाद्भिन्नकालस्य ग्राहक एव न भवतीति ॠकारो नैव स्थानी, नाप्यादेशः प्रसजतीति किं तपरत्वेन ? कृतं च तज्ज्ञापकं परेणाण्ग्रहणस्य ॥

(उद्योतः) भाष्ये—सवर्णेऽण् तपरमिति । यत् 'उरृत्' सूत्रे तपरं करोति तज्ज्ञापकं—सवर्णेऽणुग्रहणं परणकारकमिति वार्तिकाक्षरार्थः ॥ इत्येवमर्थमिति । हस्वो यथा स्यात्, दीर्घो मा भूदित्येवमर्थमित्यर्थः ॥ ऋकार इति । उदेश्यसमर्पक इत्यर्थः । न च भाव्यमानत्वेन सवर्णग्रहणाप्रसक्तेस्तद्वैयर्थ्यम्, तपरत्वाभावे आदेशान्तरनिवृत्त्यर्थत्वेन स्वरूपाभ्यनुज्ञानार्थत्वेनापूर्वबोध्यत्वाभावेन चाविधेयत्वात् । कृते तु तपरत्वे भाव्यमानताऽपीत्यन्यत् ॥

(आक्षेपभाष्यम्)

इणुग्रहणेषु तर्हि संदेहः ॥

(समाधानभाष्यम्)

असंदिग्धम् परेण, न पूर्वेण—इति ॥

(हेतुजिज्ञासाभाष्यम्)

कुत एतत् ?

(सिद्धान्तहेतुश्लोकवार्तिकम्)

***य्वोरन्यत्र परेणेण् स्यात् ।**

(भाष्यम्)

यत्रेच्छति पूर्वेण, संमृद्य ग्रहणं तत्र करोति—य्वोरिति । तच्च गुरु भवति ॥

कथं कृत्वा ज्ञापकम् ?

तत्र विभक्तिनिर्देशे संमृद्यग्रहणे चार्धचतस्रो मात्राः, प्रत्याहारग्रहणे पुनस्तिस्रो मात्राः । सोऽयमेवं लघीयसा न्यासेन सिद्धे सति यद्गरीयांसं यत्नमारभते तज्ज्ञापयत्याचार्यः—परेण, न पूर्वेणेति ॥

(प्रदीपः) अर्धचतस्र इति । अर्धेन चतस्रः, चतुर्थी हि मात्रा तत्रार्धमिति ॥

(उद्योतः) भाष्ये—संमृद्येति । आवेशेन तौ निवर्त्यैत्यर्थः । 'अर्धचतुर्थाः' इति वक्तुमुचिते आह—अर्धेनेति ॥ भाष्ये—तिस्रो मात्रा इति । 'इणः' इति पदच्छेदाभिप्रायेणेदम् । तदुक्तम्—विभक्तिनिर्देशे इति । संहितायां तु सार्धमात्राद्वयमेवेति बोध्यम् ॥

(आक्षेपभाष्यम्)

किं पुनर्वर्णोत्सत्तिविषयं णकारो द्विरनुबध्यते ?

(प्रदीपः) किं पुनरिति । वर्णोत्सत्तिः=वर्णोच्छेदः । वर्णान्तरमनुबन्धः किं न क्रियते—इत्यर्थः ॥

(उद्योतः) अणादिग्रहणेपूत्तैर्महद्भिर्यत्नैः सन्देहपरिहारे प्रतिप्रत्तिगौरवमिति लाघवाय वर्णान्तरमेव किं नानुबध्यत इत्याशयेनाह—भाष्ये—किं पुनरिति ॥

(समाधानभाष्यम्)

एतज्ज्ञापयत्याचार्यः—भवत्येषा परिभाषा—"व्याख्यानतो विशेषप्रतिपत्तिर्न हि संदेहादलक्षणम्" इति । अणुदित्सवर्णं परिहाय पूर्वेणाण्ग्रहणम्, परेणेण्ग्रहणम्—इति व्याख्यास्यामः ॥ ६ ॥

(प्रदीपः) व्याख्यानत इति । न्यायादागमाद्वा शब्दशक्तिरनुसरणीयेत्यर्थः ॥ ६ ॥

(उद्योतः) एतत्—वक्ष्यमाणम् । आचार्यः=शिवः । ननु ज्ञापितेऽपि प्रवर्तकतया निवर्तकतया वा नास्य चारितार्थ्यमत आह—न्यायादिति । उक्तो न्यायः ॥ आगमः=उपदेशपरम्परा, तत्सिद्ध एवायमर्थो णकारानुबन्धनरूपलक्ष्यव्यवहारेण बोध्यत इत्यर्थः । एवञ्च व्याख्यानेनैव—पूर्वणकारेण केचित्, केचित्परणकारेण—इति निर्णये ज्ञापकानुसरणक्लेशो वृथेति सूचितम् ॥ ६ ॥

(इति व्याख्यानतःपरिभाषाऽधिकरणम्)

(शिवसूत्रे)

ञमङणनम् ॥ ७ ॥ झभञ् ॥ ८ ॥

(सूत्रैक्यसाधनाधिकरणम्)

(आक्षेपभाष्यम्)

किमर्थमिमौ मुखनासिकावचनौ वर्णावुभावप्यनुबध्येते, न ञकार एवानुबध्येत ?

(प्रत्याक्षेपभाष्यम्)

कथं यानि मकारेण ग्रहणानि—'हलो यमां यमि लोपः' (८।४।६४) इति ?

(प्रत्याक्षेपसमाधानभाष्यम्)

सन्तु ञकारेण, "हलो यञां यञि लोपः" इति ॥

(इष्टापत्तिबाधकभाष्यम्)

नैवं शक्यम् । झकारभकारयोरपि झकारभकारयोर्लोपः प्रसज्येत ॥

(इष्टापत्तिसाधकभाष्यम्)

न झकारभकारौ झकारभकारयोः स्तः ॥

(उद्योतः) झभञ् ॥८॥ भाष्ये—न झकारेत्यादि । अप्रहितहल्मात्रानुकरणं तु यमादन्यत्र नास्तीति 'हयवरट्'सूत्रे प्रपञ्चितम् ॥

(द्वितीयाक्षेपभाष्यम्)

कथं "पुमः खय्यम्परे" (८।३।६) इति ?

(इष्टापत्तिभाष्यम्)

एतदप्यस्तु ञकारेण—"पुमः खय्यञ्परे" इति ॥

(इष्टापत्तिबाधकभाष्यम्)

नैवं शक्यम् । झकारभकारपरेऽपि हि खयि रुः प्रसज्येत ॥

(इष्टापत्तिसाधकभाष्यम्)

न झकारभकारपरः खयस्ति ॥

(तृतीयाक्षेपभाष्यम्)

कथं "ङमो ह्रस्वादचि ङमुण्नित्यम्" (८।३।३२) इति ?

(इष्टापत्तिभाष्यम्)

एतदप्यस्तु ञकारेण—"ङञो ह्रस्वादचि ङञुण्नित्यम्" इति ॥

(इष्टापत्तिबाधकभाष्यम्)

नैवं शक्यम् । झकारभकारयोरपि पदान्तयो-

झकारभकारावागमौ स्याताम् ॥

(उद्द्योतः) झकारभकारयोरपि हि पदान्तयोरिति । पदान्तयोस्तयोः सतोस्ततः परस्यादेः पदस्य झभी स्यातामित्यर्थः ॥

(इष्टापत्तिसाधकभाष्यम्)

न झकारभकारौ पदान्तौ स्तः ॥

(प्रदीपः) झभञ् ॥ ८ ॥ न झकारेति । भकारस्य पदान्तस्य जश्त्वेन भाव्यमिति तस्याभावः । उज्झेर्झकारः 'संयोगान्तस्य—' इति लुप्यते—इति तस्याप्यभावः ॥

(इष्टापत्तिबाधकैकदेशिभाष्यम्)

एवमपि पञ्चागमास्त्रय आगमिनः, वैषम्यात्संख्यातानुदेशो न प्राप्नोति ॥

(उद्द्योतः) एवमपि पञ्चागमा इति । लक्ष्यसंस्कारकालिकं संख्यासाम्यं यथासंख्यप्रवृत्तौ निमित्तमिति मन्यते ॥

(इष्टापत्तिसाधकैकदेशिभाष्यम्)

सन्तु तावद्येषामागमानामागमिनः सन्ति । झकारभकारौ पदान्तौ न स्त इति कृत्वा आगमावपि न भविष्यतः ॥

(प्रदीपः) सन्तु तावदिति । उद्देशानुदेशाभ्यां संख्यासाम्याद्यथासंख्ये लब्धे प्रयोगे यस्यागमस्यागमी विद्यते स प्रवर्तते नान्य इत्यर्थः ॥

(उद्द्योतः) सिद्धान्ती तु प्रतिपत्तिकालिकमेव संख्यासाम्यं तत्प्रवृत्तौ निमित्तमित्याह—सन्त्विति । येषामागमानामागमिनः सन्ति तेषां भवन्तु इत्यर्थः ॥ अनुदेशः=प्रतिनिर्देशः । भगवता तु स्पष्टप्रतिपत्तयेऽनुबन्धद्वयमदर्शि ॥ ७ ॥ ८ ॥

(इति सूत्रैक्यसाधनाधिकरणम्)

(अक्षरसमाम्नायाधिकरणम्)

(तत्राक्षरनिर्वचनम्)

(वार्तिकावतरणभाष्यम्)

अथ किमिदमक्षरमिति ?

(प्रदीपः) किमिदमिति । 'अक्षरसमाम्नायः' इति व्यवहारात् 'यो वा इमां स्वरशोऽक्षरशः' इति चोक्तत्वात्प्रश्नः ॥

(उद्द्योतः) इति व्यवहारादिति । 'अइउण्' सूत्रेऽयं व्यवहारो भाष्ये ॥ प्रश्न इति । तद्घटकीभूताक्षरपदार्थावगमायेति भावः ॥

(सिद्धान्तश्लोकवार्तिकम्)

***अक्षरं न क्षरं विद्यात् ।**

(भाष्यम्)

न क्षीयते, न क्षरतीति वाऽक्षरम् ॥

(प्रदीपः) अक्षरं न क्षरमिति । क्रियाशब्दोऽयं नित्यस्यार्थस्य वाचक इति दर्शयति । तत्र क्षियः क्षरतेर्वा विनाशार्थस्य नञ्पूर्वस्य रूपम् । तच्च अक्षतत्वं परमार्थतो नित्यम् । व्यवहारनित्यतया वर्णपदवाक्यस्फोटानां नित्यत्वम्, जातिस्फोटस्य वा ॥

(उद्द्योतः) भाष्ये—'अक्षरं' इत्यस्य 'न क्षरं' इति विग्रहप्रदर्शनम् ॥ तच्चेति । अक्षरं चेत्यर्थः ॥ अक्षतत्वस्यैव सत्त्वे हेतुगर्भं विशेषणमाह—परमार्थतो नित्यमिति । यतस्तद् प्रागभावाप्रतियोगित्वे सति ध्वंसाप्रतियोगित्वरूपनित्यत्ववदित्यर्थः ॥ नन्वेवं प्रकृते किमायातमत आह—व्यवहारनित्यतया वेति । सर्वेषां शब्दानामाकाशादिवत् सृष्ट्यादावुत्पत्तिः, प्रलये च नाश इत्यर्थः । एवं च व्यवहारनित्यतयाऽक्षरमक्षतत्वस्यवतां तेषां पदादिरूपाणामयं वर्णसमाम्नायः शास्त्रप्रवृत्तिद्वारा बोधक इति 'अक्षरसमाम्नायः' इति चतुर्दशसूत्रीविषयव्यवहारोपपत्तिः । एवञ्च शब्दे औपचारिकोऽक्षरपदप्रयोग इति भावः ॥ न्यायादिनयेऽप्याह—जातिस्फोटस्य वेति ॥

(सिद्धान्तश्लोकवार्तिकम्)

***अश्नोतेर्वा सरोऽक्षरम् ॥**

(भाष्यम्)

अश्नोतेर्वा पुनरयमौणादिकः सरन्प्रत्ययः । अश्नुते इत्यक्षरम् ॥

(प्रदीपः) अश्नोतेर्वेति । सरन्प्रत्ययस्यानुबन्धलोपे कृतेऽनुकरणं—सर इति । तत्रार्थमश्नुते व्याप्नोतीत्यक्षरं—पदं वाक्यं वा ॥

(उद्द्योतः) भाष्ये—अश्नोतेर्वेति ॥ तद्व्याचष्टे—अर्थमश्नुते इति । वर्णानामनर्थकत्वेन चिन्त्यमिदम् । नानादेशेषु युगपदेकस्यैव शब्दस्याभिव्यक्तिदर्शनेन स्फोटस्यापि व्यापकत्वमस्तीति भाष्यार्थ इत्यन्ये ॥

(सिद्धान्तान्तरश्लोकवार्तिकम्)

***वर्णं वाऽऽहुः पूर्वसूत्रे ।**

(भाष्यम्)

अथवा पूर्वसूत्रे वर्णस्याक्षरमिति संज्ञा क्रियते ॥

(प्रदीपः) वर्णं वाऽऽहुरिति । रूढिरियं वर्णस्येत्यर्थः ॥ पूर्वसूत्र इति । व्याकरणान्तरे 'वर्णा अक्षराणि' इति वचनात् ॥

(उद्द्योतः) ननु न्यायादिनयेऽव्याप्यवृत्तिषु विनाशिषु वर्णेषु कथं तद्व्यवहारोऽत आह—वर्णं वाऽऽहुरिति ॥ चघटितः पाठोऽत्र प्रामादिकः, व्याख्यानभाष्ये 'अथवा' इत्युक्तेः ॥ नन्वनन्तरोक्तयोगाभावात्कथं तेषु प्रयोगोऽत आह—रूढिरिति । तदुक्तं भाष्ये—अक्षरमिति संज्ञेति ॥ व्याकरणान्तरे इति । पूर्वसूत्रशब्दे षष्ठीतत्पुरुष इति भावः ॥ एवं च 'अक्षरसमाम्नायः' इत्यस्य श्रुतिरूपो वर्णसंघात इत्यत्र तात्पर्यम् ॥

(इत्यक्षरनिर्वचनम् ॥)

(वर्णोपदेशप्रयोजनप्रश्ने श्लोकवार्तिकम्)

***किमर्थमुपदिश्यते ॥ १ ॥**

(भाष्यम्)

अथ किमर्थमुपदेशः क्रियते ?

(प्रदीपः) किमर्थमिति । वर्णानां साधुत्वस्याप्रतिपाद्यत्वात्पदस्यैव साधुत्वान्वाख्यानात्प्रश्नः ॥

(उद्द्योतः) भाष्ये—उपदिश्यत इति । अक्षरसमाम्नायोपदेशः किमर्थ इत्यर्थः ॥ पूर्वं कृतोऽप्ययं विचारः कंचिद्विशेषं वक्तुं पुनः क्रियते ॥

(समाधाने श्लोकवार्तिकम्)

***वर्णज्ञानं वाग्विषयो यत्र च ब्रह्म वर्तते ॥**
तदर्थमिष्टबुद्ध्यर्थं लघ्वर्थं चोपदिश्यते ॥२॥

(भाष्यम्)

सोऽयमक्षरसमाम्नायो वाक्समाम्नायः पुष्पितः फलितश्चन्द्रतारकवत्प्रतिमण्डितो वेदितव्यो ब्रह्मराशिः । सर्ववेदपुण्यफलावाप्तिश्चास्य ज्ञाने भवति, मातापितरौ चास्य स्वर्गे लोके महीयेते ॥

इति श्रीमद्भगवत्पतञ्जलिविरचिते व्याकरणमहाभाष्ये प्रथमस्याध्यायस्य प्रथमे पादे द्वितीयमाह्निकम् ॥

(इति माहेश्वरीयं विधिशेषप्रकरणम् ॥)

(प्रदीपः) **वर्णज्ञानमिति** । वर्णा येन शास्त्रेण ज्ञायन्ते तद्वाचो विषयः, शास्त्रेण वाग्विसीयते–आबध्यते, शास्त्रेण तस्याः परिज्ञानादित्यर्थः ॥ **यत्र चेति** । ब्रह्म=वेदः पदे वर्तते । तस्य च शास्त्रं विषयः, लौकिकानां वैदिकानां च शास्त्रं विषय इत्यर्थः ॥ **तदर्थमिति** । शास्त्रप्रवृत्त्यर्थमित्यर्थः ॥ **इष्टबुद्ध्यर्थमिति** । कलादिदोषरहितवर्णज्ञानार्थमित्यर्थः ॥ **लघ्वर्थमिति** । अनुबन्धकरणार्थमित्यर्थः ॥ **वाक्समाम्नाय इति** । एतावद्भिरेव वर्णैर्वाग्व्यवहार इत्यर्थः ॥ **पुष्पितः फलित इति** । दृष्टादृष्टफलाभ्यामभ्युदयनिःश्रेयसाभ्यां ॥ **चन्द्रतारकवदिति** । अनादित्वान्नित्यत्वं वाग्व्यवहारस्य सूचयति ॥ **ब्रह्मराशिरिति** । ब्रह्मतत्त्वमेव शब्दरूपतया प्रतिभातीत्यर्थः ॥ **सर्ववेदेति** । सर्ववेदाध्ययनकृतस्य पुण्यस्य यत्फलं तत्प्राप्नोति ॥ **मातापितराविति** । माहात्म्यातिशयः शास्त्रस्य प्रत्याहारमात्रफलाख्यानद्वारेण ख्याप्यते ॥ **महीयेते इति** । पूजां प्राप्नुत इत्यर्थः । महीयशब्दः कण्ड्वादियगन्तः ॥

इत्युपाध्यायजैयटपुत्रकैयटकृते महाभाष्यप्रदीपे प्रथमाध्यायस्य प्रथमे पादे द्वितीयमाह्निकम् ॥ २ ॥

(उद्द्योतः) **येन शास्त्रेणेति** । चतुर्दशसूत्र्यात्मकेन तन्मूलकपाणिनिव्याकरणेन चेत्यर्थः ॥ तत्=शास्त्रम् ॥ **वाचो विषयः**—बन्धनं, प्रतिपादकमित्यर्थः ॥ भाष्ये **'यत्र च'** इत्यनेन वाक् परामृश्यते इत्याह—**पदे वर्तत इत्यादिना** ॥ **शास्त्रं विषय इति** । प्रतिपादकमित्यर्थः । वर्णज्ञानं शास्त्रं वाचो विषयः ॥ का सा वाक् ? यत्र ब्रह्म च वर्तते, चात्पुराणादि–इति भाष्याक्षरार्थः ॥ **'तदर्थं'** इत्येतद्व्याचष्टे—**शास्त्रप्रवृत्त्यर्थमिति** ॥ **कलादीति** । इदं प्रयोजनं पस्पशान्ते दूषितम् ॥ **अनुबन्धकरणार्थमिति** । **'लघ्वर्थं'** इत्यक्षराणामत्रार्थे स्वारस्यं **चिन्त्यम्** । अनुबन्धकरणमूलकप्रत्याहारद्वारा लाघवेन शास्त्रप्रवृत्त्यर्थमित्यर्थो वा ॥ **वाक्समाम्नायः**—वाक्सङ्घोपाय इत्यर्थः । तदाह—**एतावद्भिरेवेति** ॥ दृष्टफलेनाभ्युदयेन वा **पुष्पितः** । अदृष्टफलेन निःश्रेयसेन वा **फलितः** ॥ **वाग्व्यवहार**ऽक्षरसमाम्नायोद्देशेन प्रवृत्तविशेषणानामन्यपरतया योजने भाष्यविरोधः। अत एवैतत्प्रतीकमुपादाय हरिणा–''**अस्याक्षरसमाम्नायस्य वाग्व्यवहारजनकस्य न कश्चित्कर्ताऽस्ति, एवमेव वेदे पारंपर्येण स्मर्यमाणम्**'' इति व्याख्यातम् ॥ **ब्रह्मतत्त्वमेवेति** । तदुक्तं नन्दिकेश्वरेण—

'अकारः सर्ववर्णाग्र्यः प्रकाशः परमेश्वरः ॥'

इत्यादिना सर्ववर्णानां मायेश्वररूपता वर्णेभ्य एव च महदादिसृष्टिरित्यर्थपरतया चतुर्दशसूत्रीं योजयता ॥ तदाह—**सर्ववेदेत्यादि** ॥

अन्ये तु वर्णज्ञानं—चतुर्दशसूत्र्यात्मकं शास्त्रं **वाचः**—वेदशास्त्रपुराणरूपायाः सकलवाचो **विषयः**—बन्धनम् । **यत्र च** वर्णसमाम्नाये **ब्रह्म** बोध्यतया **वर्तते** । व्याख्याता चैषा चतुर्दशसूत्री ब्रह्मपरतया नन्दिकेश्वरेण । **तदर्थं**—सकलवाग्ज्ञानार्थं ब्रह्मबोधनार्थं च । अनेन सकलवेदाध्ययनेन यत् फलं तदक्षरसमाम्नायज्ञानेन सूचितम् । तद्वक्ष्यति—**सर्ववेदेत्यादि** ॥ **'सोऽयं'** इत्यादिभाष्यग्रन्थश्चैतच्छ्लोकपूर्वार्धस्यैव व्याख्यानपरः । तत्र **'वर्णज्ञानं'** इत्यस्य व्याख्या–**'सोऽयमक्षरसमाम्नायः'** इति । **'वाग्विषयः'** इत्यस्य व्याख्या–**'वाक्समाम्नायः'** इति, सर्ववाग्मूलत्वात् । तदध्ययनतन्मूलव्याकरणाध्ययनाभ्यां **पुष्पितः** । **फलितः**–तदर्थभावनया जनिततत्त्वज्ञानरूपफलः । **चन्द्रतारकवत् प्रतिमण्डित** इत्यनेनाऽस्यानादित्वं सूचयति । तादृशोऽयं **ब्रह्मराशिर्वेदितव्यः**, बोध्यबोधकयोरभेदात् ॥ **सर्ववेदेति** । सर्ववेदाध्ययनजन्यपुण्यफलस्य चित्तशुद्धिरूपस्य प्राप्तिरस्य ज्ञानेऽध्ययनमात्रे भवति । इदमेव पूर्वं पुष्पितत्वम् । तादृशपुत्रवत्त्वेन च मातापित्रोः स्वर्गे पूजा भवति । यथा कृतराजसूययुधिष्ठिररूपपुत्रेण पाण्डोः स्वर्गे पूजेति । **इष्टबुद्ध्यर्थ**मित्यादि तु प्राग्व्याख्यातत्वान्न व्याख्यातमित्याहुः ॥

इति कालोपनामकशिवभट्टसुतसतीगर्भजनागेशभट्टकृते भाष्यप्रदीपोद्द्योते प्रथमाध्यायस्य प्रथमे पादे द्वितीयमाह्निकम् ॥

(अक्षरसमाम्नायाधिकरणं समाप्तम्)

(इति प्रत्याहाराह्निकम्)

प्रथमाध्याये प्रथमपादे तृतीयाह्निकम् ।

अथ पाणिनीयं विधिशेषप्रकरणम् ।

(१-वृद्धिसंज्ञासूत्रम् १ । १ । ३ । १ ॥)

वृद्धिरादैच् १ । १ । १ ॥

(सूत्रस्वरूपसाधनाधिकरणम्)

(उद्द्योतः) वृद्धिरादैच् ॥ द्विपदं सूत्रं, 'कृतमनयोः साधुत्वं'इति भाष्यदर्शनात् । अन्यथोद्देश्यानेकत्वाद् वृद्धिशब्दस्यावृत्तिर्वाक्यार्थबोधाय कार्या स्यात् । द्वन्द्वे तु समाहारस्यैकस्योद्देश्यस्य शब्दतः संभवात् तां विनाऽपि सिध्यति । न च समाहारे टच्प्रसङ्गः, समासान्तविधेरनित्यत्वात् । 'प्रतेरंश्वादयः' इति सूत्रेऽश्वादिगणे राजन्शब्दपाठाल्लिङ्गात् । अन्यथा 'राजाहः' इति टचा सिद्धे किं तेन ॥ यद्वा पदत्रयं, पस्पशायां भाष्ये 'वृद्धिः-आत्-ऐच्' इति पदविभागदर्शनात् । वृद्धिशब्दस्त्वावृत्त्या योज्यः । अस्मिन् पक्षे 'अनयोः' इति भाष्यं खण्डयोरित्यर्थकम् ॥

(आक्षेपभाष्यम)

कुत्वं कस्मान्न भवति "चोः कुः" पदस्य-इति ?

(प्रदीपः) वृद्धिरादैच् ॥ १।१।१ ॥ **कुत्वं कस्मादिति** । अनेकशक्तेः शब्दस्य शक्त्यवच्छेदेन संज्ञिनि विनियोगान्नित्यत्वाच्च सर्वसंज्ञानां लौकिकत्वादादैच्छब्दस्यानुकरणशब्दत्वाज्जातिशब्दत्वाद्वा शास्त्रप्राप्तिरस्तीति **प्रश्नः** । तत्र कुशब्दः पञ्चसु वर्णेष्वासक्तरूपो वाचकत्वेन विनियुक्त इति शब्दस्वरूपे प्रवृत्तिनिमित्ते भावप्रत्ययः ॥

(उद्द्योतः) असाधुशब्दोच्चारणे पाणिनेरश्रद्धेयतापत्त्या तदुक्तपदानां साधुत्वं विचारयति—भाष्ये—**कुत्वमित्यादि** । ननु ऐच्छब्दस्य 'आदिरन्त्येन-'इत्यनेन कृत्रिमतया लौकिकवैदिकबहिर्भूतत्वेन कथं सुबादिशास्त्रप्राप्तिः ? लौकिकत्वं च लोकेऽर्थबोधनाय प्रयुक्तशब्दत्वम्, अत आह—**अनेकेति** ॥ '**नित्यत्वाच्च**' इति चो हेतौ, यतः शब्दार्थसंबन्धस्य नित्यत्वात्सर्वसंज्ञानां नित्यत्वमतो लौकिकत्वाच्छास्त्रप्राप्तिरित्यन्वयः ॥ लोकेऽर्थान्तरेऽप्रसिद्धानामपि संज्ञानां नित्यत्वमिति बोधयितुं सर्वशब्दः ॥ नन्वेवं 'वृद्धिरादैच्'इत्यादीनां वैयर्थ्यमत आह—**शक्तीति** । **शक्त्यवच्छेदः**-तत्संकोचः । **विनियोगः**-विशेषे नियमः । अभिमतातिरिक्तार्थान्तरव्युदासाय च सः ॥ परिसंख्यायां चात्र शास्त्रे प्रायेण नियमव्यवहार इति बोध्यम् ॥

यद्वा-**शक्त्यवच्छेदः**—शक्तिनिश्चयः, '**शब्दार्थस्यानवच्छेदे**' इत्यादाववच्छेदशब्दस्य तदर्थकत्वदर्शनात् । फलरूपे हेतौ तृतीया ॥ **विनियोगः**-उपदेशः । शक्तिनिश्चयफलकोपदेशादित्यर्थः । एवंच तत्सङ्केतकरणरूपप्रकरणादर्थान्तराप्रतीतिरिति बोध्यम् ॥ इदमेव युक्तं, सर्वार्थवाचकत्वेऽपि सङ्केतरूपत्वेनाज्ञातशक्तिबोधकतया विधित्वसंभवे नैषां नियमार्थत्वासंभवात् ॥ नन्वेवं लौकिकार्थबोधो न स्यादत उक्तम्—'**अनेकशक्तेः**' इति । स्वशास्त्रे एव प्रकरणादन्यार्थाबोध इति भावः । अनेकस्मिन्ननेका वा शक्तिरस्येति विग्रहः । अन्त्ये 'सर्वनाम्नो वृत्तिमात्रे' इति पुंवत्त्वम् । कोपधप्रतिषेधे तद्धितवुग्रहणाद्वा 'स्त्रियाः'-इति पुंवत्त्वम् । आश्रयभेदादेव शक्तिभेद इति मते आद्यम् । निरूपकभेदाद्भेदे द्वितीयः । नित्ये शब्दार्थसंबन्धे पुरुषव्यापारात्प्रागवाचकस्य न पुरुषव्यापारेण वाचकता शक्या कर्तुमतः '**सर्वे सर्वार्थवाचकाः**' इत्यभ्युपगमादनेकशक्तित्वावसायः । तादात्म्यमेव च शब्दार्थयोः शक्तिः । अत्र पक्षे गौणमुख्यविभागः प्रसिद्ध्यप्रसिद्धिमूलः । '**अन्यायोऽनेकार्थत्वं**' इति त्वश्रद्धेयमेवेति निरूपितं मञ्जूषायाम् । अत्र लौकिकशब्दत्वं **साध्यम्**, शास्त्रीयसंज्ञात्वसमानाधिकरणं नित्यत्वं **हेतुः**, अतो न वैदिकेषु व्यभिचारः । '**सर्वसंज्ञानां**' इति वदता सूचितमिदम् ॥ '**अपूर्वाः संज्ञाः क्रियन्ते**' इति पक्षेऽपि लौकिकत्वं साधयति—**अनुकरणेति** । अयमपि लौकिकत्वे हेतुः, '**आदिरन्त्येन**' इत्यनेन संज्ञात्वेन विनियुक्तस्यैच्शब्दस्यानुकरणं सूत्रे, लक्षणया तेनैवोपस्थापितयोरैकारौकारयोस्तात्पर्यवशाच्छाब्दबोधविषयतेति बोध्यम् ॥ अनुकरणे च सर्वशब्दानां साधुत्वेन शास्त्रविषयतेति भावः ॥ यत्तु '**ऐच्**' इत्याद्यन्तावयवद्वारा समुदायानुकरणमिति । तन्न । तथा सति '**आदिरन्त्येन-**' इति सूत्रवैयर्थ्यापत्तेः । वृद्धिशब्दादेः शास्त्रविषयताया एवमप्यनुपपादनाच्च ॥ नन्वनुकरणस्याननुभवः । किं च **त्रयी शब्दानां प्रवृत्तिरिति** पक्षे उक्तहेतुद्वयस्याप्यभावोऽत आह—**जातीति** । वैयाकरणव्यवहाराच्च तत्सिद्धिरिति भावः ॥ अत्र पक्षे जातिबोधार्थमेव संज्ञासूत्राणीति बोध्यम् । अत्रापि पक्षे लौकिकत्वं संज्ञापक्षवदेव बोध्यम् ॥ **हरदत्तस्तु—**वृद्धिशब्दो वृधेर्भावे क्तिन्नन्तः, अभेदोपचाराच्च वृद्धियुक्तादैक्षु वृत्तिः । लक्षणयैव सिद्धे सूत्रं नियमार्थं, वृद्धियुक्तप्लुतदीर्घैकारादीनां बोधो मा भूदिति त्रयीपक्षे सूत्रार्थमाह । तन्न । 'अदेङ् गुणः' इत्यादावसंभवात् ॥ ननु कुत्वमित्यत्र संज्ञात्वपक्षे ककारादिपञ्चकगतप्रवृत्तिनिमित्ताभावात् त्वप्रत्ययोऽनुपपन्नः । किं चात्र ककारस्य प्राप्तिर्न तु कुवृत्तिधर्मस्येति कुत्वमित्यसङ्गतमत आह—**तत्रेति** । **आसक्तरूपः**-संबद्धस्वरूपः । एवञ्च कुशब्दः कुशब्दवत्ककारादिषु शक्त इत्येवं शक्तिग्रहात्कुशब्दस्य प्रवृत्तिनिमित्तत्वम् । संबन्धश्चानादिव्यवहारसिद्धतादात्म्यम् । तादात्म्येन कुशब्दं प्रवृत्तिनिमित्तीकृत्य शक्तित्वेन तस्य ग्रहे बाधकाभावात् ॥ **केचित्तु**—शब्दस्य स्वरूपं-कुशब्दत्वं सामान्यं, तत्कादिष्वारोपितं प्रवृत्तिनिमित्तं तद्व्यक्तिश्च वाच्येत्याहुः । तेन च कुत्वशब्देन स्वार्थाश्रयः ककारो लक्ष्यते-इति **ककारः कस्मान्नेति** चोद्यपर्यवसानम् ॥ वस्तुतः कुत्वकुशब्दयोर्भत्वभसंज्ञापदयोश्च पर्यायतेति '**ऋलृक्**' सूत्रे निरूपितमिति न कश्चिद्दोषः ॥

(समाधानभाष्यम्)

भत्वात् ॥

(आक्षेपभाष्यम्)

कथं भसंज्ञा ?

(समाधानभाष्यम्)

"अयस्मयादीनि छन्दसि" इति ॥

(समाधानबाधकभाष्यम्)

'छन्दसि' इत्युच्यते, न चेदं छन्दः ॥

(समाधानसाधिका भाष्येष्टिः ।)

छन्दोवत्सूत्राणि भवन्ति ॥

(प्रदीपः) छन्दोवदिति । न वैशेषिकादिसूत्राणि, अपि त्वष्टाध्याय्याकरणसूत्राण्येव । इष्टिश्चेयम्—'छन्दोवत्–' इति ॥

(उद्द्योतः) अङ्गत्वात्—वेदपदार्थबोधनद्वारा वेदोपकारकत्वात् । मुखं व्याकरणमित्यादिनाऽङ्गत्वनिरूपणाच्च । प्रधानं च षडङ्गेषु व्याकरणमिति पस्पशायां भाष्योक्तेश्च ॥ अस्यामिष्टौ नार्थत्वं प्रयोजकं, नैवेष्टिरस्ति–'छन्दोवत्कवयः कुर्वन्ति' इति पूर्वाक्याविति सूत्रे भाष्योक्तेः । तस्मादङ्गत्वमेव प्रयोजकमिति भावः ॥

ननु छन्दसि विहितस्य सूत्रे कथं प्रवृत्तिरत आह—इष्टिरिति । तथा च भाष्यकारीयातिदेशात्सूत्रेषु छन्दःकार्यप्रवृत्तिरिति भावः ॥

(आक्षेपभाष्यम्)

यदि भसंज्ञा, "वृद्धिरादैजदेङ् गुणः" इति जश्त्वमपि न प्राप्नोति ॥

(उद्द्योतः) भाष्ये—जश्त्वमपीति । संहितया पाठे इत्यर्थः ॥

(समाधानभाष्यम्)

उभयसंज्ञान्यपि छन्दांसि दृश्यन्ते । तद्यथा— 'स सुष्टुभा स ऋक्वता गणेन' । पदत्वात्कुत्वम्, भत्वाज्जश्त्वं न भवति । एवमिहापि पदत्वाज्जश्त्वम्, भत्वात्कुत्वं न भविष्यति ॥

(उद्द्योतः) उभयसंज्ञान्यपीति । उभे संज्ञे येषामिति विग्रहः । संज्ञाद्वयहेतुककार्यदर्शनेन तद्दर्शनेनेति भावः ॥

(इति सूत्रस्वरूपसाधनाधिकरणम्)

(अथ तद्भावितपक्षनिराकरणाधिकरणम्)

(उभयपक्षस्वरूप-तद्भावितपक्षदूषणभाष्यम्)

किं पुनरिदं तद्भावितग्रहणम्—वृद्धिरित्येवं ये आकारैकारौकारा भाव्यन्ते तेषां ग्रहणम्, आहोस्विदादैज्मात्रस्य?

किं चातः?

यदि तद्भावितग्रहणम्, 'शालीयः-मालीयः' इति वृद्धलक्षणश्छो न प्राप्नोति ।

आम्रमयम्-शालमयम्, वृद्धिलक्षणो मयण्न प्राप्नोति ।

आम्रगुप्तायनिः-शालगुप्तायनिः, वृद्धिलक्षणः फिञ् न प्राप्नोति ॥

(प्रदीपः) किं पुनरिति । उभयथा शास्त्रे दर्शनात्पक्षद्वयेऽपि दोषसंभवात्प्रश्नः ॥

(उद्द्योतः) ननु सूत्रादादैज्मात्रग्रहणपक्ष एव प्रतीयत इति प्रश्नानुपपत्तिरत आह—उभयथेति । लुगादिसंज्ञासु तद्भावितपक्षस्य, लोपसंज्ञायामदर्शनमात्रस्येति भावः ॥ ननु टिघुभादिसंज्ञास्वतद्भावितानामेव ग्रहणं दृश्यते–इति सोऽपि पक्षः शङ्कितुमुचित इति चेत् । न । तत्र हि तद्भावितासंभवादतद्भावितानामेव ग्रहणम्, न च तथा प्रकृते–इति उभयथेत्युक्तम् ॥ वृद्धिशब्दे तत्प्राणङ्गीकारे तद्भावितग्रहणम् । वृद्धिशब्दैकत्वे द्वितीयः पक्ष इति भावः ॥ भाष्ये—वृद्धिलक्षणो मयडिति । 'नित्यं वृद्धशरादिभ्यः' इत्यस्य वृद्धसंज्ञाद्वारा वृद्धिलक्षणत्वं बोध्यम् ॥ 'वृद्धलक्षणः' इति पाठे एषां वृद्धित्वाभावेन समुदायानां वृद्धत्वाभावादित्यर्थः ॥ फिञिति । उदीचां वृद्धादगोत्रादिति । न च प्राचामवृद्धादिति फिनाऽप्येतत्सिद्धं, पुंवद्भावनिषेधोऽप्याम्रगुप्तायनीभार्य इत्यादौ जातेश्चेति सिद्ध इति वाच्यम् । आम्रगुप्तायनेरपत्यं युवेत्यर्थेऽणो द्व्यचक्षत्रियार्षञित इति लुकि आम्रगुप्तायनिरित्येव रूपं पितरि पुत्रे चेष्यते, फिनि तु ञितः परत्वाभावान्न सिध्येत् । न चाब्राह्मणगोत्रमात्राद्युवप्रत्ययस्योपसंख्यानमिति तत्सिद्धिः । ब्राह्मणगोत्रे तदप्रवृत्तेः ॥

(द्वितीयपक्षे दूषणभाष्यम्)

अथादैज्मात्रस्य ग्रहणम्, सर्वो भासः-सर्वभास इति "उत्तरपदवृद्धौ सर्वं च" इत्येष विधिः प्राप्नोति ॥

इह तावती भार्या यस्य-तावद्भार्यः-यावद्भार्यः "वृद्धिनिमित्तस्य–" इति पुंवद्भावप्रतिषेधः प्राप्नोति॥

(उद्द्योतः) भाष्ये—एष विधिरिति । पूर्वपदान्तोदात्तत्वमित्यर्थः ॥ तावद्भार्ये 'आसर्वनाम्नः' इत्यात्वस्य वतुनिमित्तमिति पुंवत्त्वनिषेधप्राप्तिः ॥

(सिद्धान्तभाष्यम्)

अस्तु तर्हि—आदैज्मात्रस्य ग्रहणम् ॥

(उद्द्योतः) यदि प्रथमपक्षे दोषो दुरुद्धरोऽस्तु तर्हीत्यन्वयः ॥

(आक्षेपानुवादभाष्यम्)

ननु चोक्तं—सर्वो भासः-सर्वभास इति "उत्तरपदवृद्धौ सर्वं च" इत्येष विधिः प्राप्नोतीति ॥

(समाधानभाष्यम्)

नैष दोषः । नैवं विज्ञायते—उत्तरपदस्य वृद्धिः-उत्तरपदवृद्धिः, उत्तरपदवृद्धाविति ॥

कथं तर्हि?

'उत्तरपदस्य' इत्येवं प्रकृत्य या वृद्धिस्तद्वत्युत्तरपदे-इत्येवमेतद्विज्ञायते । अवश्यं चैतदेवं विज्ञेयम् । तद्भावितग्रहणे सत्यपीह प्रसज्येत—सर्वः कारकः-सर्वकारक इति ॥

(प्रदीपः) उत्तरपदस्येत्येवमिति । तत्र हि 'वृद्धौ सर्वं च' इत्यप्युच्यमाने वृद्धिमात्रस्योत्तरपदस्याभावात्सामर्थ्याद्वृद्धिमदुत्तरपदं ग्रहीष्यत इत्यतिरिच्यमानमुत्तरपदग्रहणं सामर्थ्यादुत्तरपदाधिकारमवगमयति ॥

(उद्द्योतः) तद्वत्युत्तरपदे इति । समासाक्षिप्तोत्तरपदशब्देन सामानाधिकरण्यायोत्तरपदस्येत्येवं वृद्धिर्यस्मिन्निति बहुव्रीहिरिति

भावः ॥ तत्राधिकारलक्षणायां बीजमाह—तत्र हीति ॥ न च आ-अवतीति–औः, सर्वस्य-औः–सर्वौरित्यादौ वृद्धिरूपोत्तरपदसंभवः । न चैकादेशे व्यपवर्गाभावः । नेन्द्रस्येति निषेधेन पूर्वोत्तरपदसंबन्धिकार्यस्यैकादेशात्प्राक् प्रवृत्तिस्वीकारात् । तथा च सर्वशब्दान्तोदात्तत्वे शेषनिघातेन औकारस्यानुदात्तत्वे एकादेशस्य स्वरितो वानुदात्ते इति पाक्षिकः स्वरितः स्यादिति वाच्यम् ॥ तादृशानामभिधाने दृढतरमानाभावात्, स्वरितत्वाद्वा-अधिकारलाभ इति बोध्यम् ॥

(द्वितीयदूषणनिराकरणभाष्यम्)

यदप्युच्यते-इह तावती भार्या यस्य-तावद्भार्यः, यावद्भार्य इति "वृद्धिनिमित्तस्य-"इति पुंवद्भावप्रतिषेधः प्राप्नोतीति ।

नैष दोषः । नैवं विज्ञायते—वृद्धेर्निमित्तं-वृद्धिनिमित्तं, वृद्धिनिमित्तस्येति ॥

कथं तर्हि ?

वृद्धेर्निमित्तं यस्मिन्सोऽयं वृद्धिनिमित्तः, वृद्धिनिमित्तस्येति ॥

किं च वृद्धेर्निमित्तम् ?

योऽसौ ककारो णकारो ञकारो वा ॥

अथवा यः कृत्स्नाया वृद्धेर्निमित्तं तद्वृद्धिनिमित्तम् ॥

कश्च कृत्स्नाया वृद्धेर्निमित्तम् ?

यस्त्रयाणामाकारैकारौकाराणाम् ॥

(प्रदीपः) वृद्धेर्निमित्तं यस्मिन्निति । निमित्तशब्दोपादानसामर्थ्याद्व्यधिकरणपदो बहुव्रीहिराश्रीयते । अन्यथा 'वृद्धेस्तद्धितस्य'इत्येवं ब्रूयात् । वृद्धिनिमित्तत्वाच्च तद्धित एव वृद्धिशब्देनाभिधायिष्यते । अथवा वृद्धेः संबन्धी यस्तद्धित इति वैयधिकरण्येन संबन्ध आश्रयिष्यते ॥ योऽसौ ककार इति । कणञेषु सत्सु वृद्धिर्भवतीति तेषामेव निमित्तत्वम् ॥ अथवेति । निमित्तशब्दोपादानादेवाश्रितबहुत्वसंख्यो वृद्धिशब्दः समस्यते, वृद्धीनां निमित्तं-वृद्धिनिमित्तमिति ॥

(उद्द्योतः) अन्यथा वृद्धेरिति । वृद्ध्यात्मकतद्धिताभावाद्वृद्धिनिमित्तग्रहणमिति भावः ॥ नन्वर्शःशब्दादर्शआद्यचि टापि 'अर्शसा' इत्यादौ वृद्धिरूपसंभव इत्यरुचेराह—अथवेति । व्यधिकरणबहुव्रीह्याश्रयणसामर्थ्यादेव व्यपदेशिवद्भावाप्रवृत्तिरिति भावः ॥ तेषामेवेति । एवशब्दोऽप्यर्थे । विशिष्टस्य निमित्तत्वे विशेषणानामपि तत्त्वमिति भावः ॥ ननु वृत्तावभेदैकत्वसंख्यावगतेर्बहुवचनान्तेन विग्रहोऽनुपपन्नोऽत आह—निमित्तेति । तत्र कार्त्स्न्यं प्रतिपत्तिकालिकं न प्रयोगसमवायीति न पारिपथ्याभार्ये दोषः । न च वैयाकरणभार्येऽपि निषेधापत्तिः, इष्टापत्तेः । अत एवादैज्मात्रस्येति पक्षेऽत्र दोषानुद्भावनम् । तद्भावितानामेवेति पक्षेऽपि न य्वाभ्यामिति सूत्रे ऐजंशोऽपि वृद्धिपदसंबन्धेन निषेधप्रवृत्तिरत्र सूपपादा । अत एव देविकाशिंशपेति सूत्रे भाष्यकृता तत्संबंधो दर्शित इत्याहुः ॥ आदेज्मात्रग्रहणादेव 'प्राक्रादीनां च' इति सार्थकम् । अन्यथाऽस्यावृद्धत्वात् 'प्रस्थेऽवृद्धं-' इत्येव सिद्धे किं तेन ॥

(इति तद्भावितपक्षनिराकरणम् ॥)

(अथ संज्ञासूत्रत्वसाधनाधिकरणम्)

(६० आक्षेपवार्तिकम् ॥ १ ॥)

॥*॥ संज्ञाधिकारः संज्ञासंप्रत्ययार्थः ॥*॥

(भाष्यम्)

"अथ संज्ञा" इत्येवं प्रकृत्य वृद्ध्यादयः शब्दाः पठितव्याः ।

किं प्रयोजनम् ?

'संज्ञासंप्रत्ययार्थः' वृद्ध्यादीनां शब्दानां 'संज्ञा' इत्येष संप्रत्ययो यथा स्यात् ॥

(प्रदीपः) 'संज्ञाधिकारः–' इति वार्तिकम् । तस्य व्याख्यानं—अथ संज्ञेत्येवमिति । 'अथ'शब्दः संज्ञायाः प्रस्तावद्योतनार्थः ॥ वृद्ध्यादीनामिति । 'संप्रत्ययः'इत्येतदपेक्षया कर्मणि षष्ठी । वृद्ध्यादयः संज्ञात्वेन यथा प्रतीयेरन्नित्यर्थः ॥

(उद्द्योतः) वार्तिकमिति । सूत्रेऽनुक्तदुरुक्तचिन्ताकरत्वं वार्तिकत्वम् ॥ एतेन सूत्रव्याख्यानाय प्रवृत्तस्य कात्यायनस्यानुक्तादुरुक्तचिन्तेत्यपास्तम् ॥ प्रस्तावेति । वार्तिकेऽधिकारशब्दोक्तः स इति भावः ॥ वृद्ध्यादीनां संज्ञात्वाज्ञेदनिबन्धनषष्ठ्यनुपपत्तेरत आह—संप्रत्यय इति ॥ भाष्ये—संज्ञेत्येष इति । शब्दार्थयोनानामितरेतराध्यासादिदं नानुपपन्नम् ॥

(६१ आक्षेपसाधकवार्तिकम् ॥ २ ॥)

॥ * ॥ इतरथा ह्यसंप्रत्ययो यथा लोके ॥ * ॥

(भाष्यम्)

अक्रियमाणे हि संज्ञाधिकारे वृद्ध्यादीनां 'संज्ञा' इत्येष संप्रत्ययो न स्यात् ॥

इदमिदानीं बहुसूत्रमनर्थकं स्यात् ।

अनर्थकमित्याह ।

कथम् ?

'यथा लोके' । लोके ह्यर्थवन्ति चानर्थकानि च वाक्यानि दृश्यन्ते ।

अर्थवन्ति तावत्—'देवदत्त गामभ्याज शुक्लां दण्डेन' 'देवदत्त गामभ्याज कृष्णाम्' इति ।

अनर्थकानि—'दश दाडिमानि षडपूपाः कुण्डमजाजिनं पललपिण्डः । अधोरुकमेतत्कुमार्याः स्फैयकृतस्य पिता प्रतिशीनः' इति ॥

(प्रदीपः) यथा लोके इति । कात्यायनेनासंप्रत्यये लोको दृष्टान्तत्वेनोपात्तः । भाष्यकारस्तु वाक्याध्याहारेणानर्थकत्वे लोकं दृष्टान्तत्वेन योजयति—बहुसूत्रमिति । बहुव्रीहिः, प्रकरणं चान्यपदार्थः । समाहारे द्विगुर्वा ॥ अर्थवन्ति चेति । यथा लोकोऽर्थवन्ति प्रयुङ्क्ते, एवमनर्थकान्यपीत्यर्थः । यावच्चास्त्वमाचार्यस्य न साधितं तावदनर्थकत्वशङ्का, झटिति समन्वयानवगमाद्वा ॥ दश दाडिमानीति । पदार्थानां समन्वयाभावादत्रानर्थकत्वम् ॥

(उद्योतः) भाष्यकारस्त्विति । अधिकारं विनाऽसंप्रत्यये दृष्टान्तस्य लौकिकस्याभावादर्थापरिज्ञाने दृष्टान्तानुपयोगाच्चेति तद्भावः॥ वाक्याध्याहारेणेति । 'इदमिदानीं' इति वाक्याध्याहारेणेत्यर्थः ॥ ननु द्विगौ अकारान्तोत्तरपदत्वात् स्त्रीत्वे ङीप्स्यादत आह—बहुव्रीहिरिति। अन्यपदार्थस्याशाब्दत्वाद्बहुव्रीहिर्दुर्ज्ञेयोऽत आह—समाहारे इति । पात्रादित्वात्स्त्रीत्वाभावः । अत एव त्रिसूत्रीत्यादि सङ्गच्छते, बहुसूत्रशब्दस्यैव तत्र पाठात्–इत्यभिमानः ॥ नन्वनर्थकदृष्टान्तेऽर्थवन्तीत्यादि व्यर्थमत आह—यथेति । यद्यप्यन्वितार्थकपदसमूह एव वाक्यम्, तथापि भाष्ये पदसमूहे एव वाक्यशब्दः प्रयुक्तोऽतः 'अनर्थकानि वाक्यानि' इति न विरुद्धम् ॥ झटिति-विनाऽऽचार्याचारादिज्ञानेन ॥ पदार्थानाम्-कुण्डमजाजिनमित्यादीनाम् । स्फ्यकृतोऽपत्यं—स्फैयकृतः ॥

(६२ आक्षेपान्तरवार्तिकम् ॥ ३ ॥)

॥ * ॥ संज्ञासंज्ञ्यसंदेहश्च ॥ * ॥

(भाष्यम्)

क्रियमाणेऽपि संज्ञाधिकारे संज्ञासंज्ञिनोरसंदेहो वक्तव्यः ॥

कुतो ह्येतत्—वृद्धिशब्दः संज्ञा, आदैचः संज्ञिन इति । न पुनरादैचः संज्ञा, वृद्धिशब्दः संज्ञीति ?

(प्रथमाक्षेपानुवादभाष्यम्)

यत्तावदुच्यते-'संज्ञाधिकारः कर्तव्यः संज्ञासंप्रत्ययार्थः' इति ।

न कर्तव्यः ॥

(६३ सिद्धान्तवार्तिकम् ॥ ४ ॥)

॥ * ॥ आचार्याचारात्संज्ञासिद्धिः ॥ * ॥

(भाष्यम्)

आचार्याचारात्संज्ञासिद्धिर्भविष्यति ॥

किमिदं—आचार्याचारादिति ?

आचार्याणामुपचारात् ॥

(प्रदीपः) आचार्याचारादिति । आचार्याणां व्यवहारादित्यर्थः ॥

(उद्योतः) उपचारोनाम गौणी वृत्तिरिति भ्रमं व्युदस्यति—व्यवहारादिति । अनेन व्यवहाराच्छक्तिग्रह उक्तः । स च शक्तिग्राहकशिरोमणिः ॥

(६४ सिद्धान्तिवार्तिकम् ॥ ५ ॥)

॥ * ॥ यथा लौकिकवैदिकेषु ॥ * ॥

(भाष्यम्)

तद्यथा लौकिकेषु वैदिकेषु च कृतान्तेषु ॥ लोके तावन्मातापितरौ पुत्रस्य जातस्य संवृतेऽवकाशे नाम कुर्वाते-देवदत्तो यज्ञदत्त इति । तयोरुपचारादन्येऽपि जानन्ति इयमस्य संज्ञेति ॥ वेदे याज्ञिकाः संज्ञां कुर्वन्ति—स्फ्यो यूपश्चषाल इति । तत्रभवतामुपचारादन्येऽपि जानन्ति—इयमस्य संज्ञेति ॥

(उद्योतः) भाष्ये—वेदे याज्ञिका इति । यज्ञकाण्डद्रष्टारो ऋषय इत्यर्थः । वेदकर्तृत्ववत्संज्ञाकर्तृत्वं तेषां द्रष्टव्यम् ॥

(दार्ष्टान्तिकभाष्यम्)

एवमिहापि । इहैव तावत्केचिद्व्याचक्षणा आहुः—वृद्धिः शब्दः संज्ञा, आदैचः संज्ञिन इति ॥

अपरे पुनः "सिचि वृद्धिः" इत्युक्त्वाऽऽकारैकारौकारानुदाहरन्ति । तेन मन्यामहे—यया प्रत्याय्यन्ते सा संज्ञा, ये प्रतीयन्ते ते संज्ञिन इति ॥

(प्रदीपः) वृद्धिशब्दः संज्ञेति । वृद्धिशब्दस्य प्रत्यायनशक्तिर्व्याख्यानेनैव प्रकाश्यते । यथा-आदैचां वर्णानामिति वर्णत्वम् ॥ अपर इति । प्रदेशाद्वा संज्ञासंज्ञ्यभिव्यक्तिः । संज्ञासूत्रार्थाद्वा प्रदेशार्थस्य व्यवस्थेत्यर्थः ॥

(उद्योतः) भाष्ये—इहैवेति । वृद्धिरादैच्सूत्रे एवेत्यर्थः ॥ असत्याः शक्तेर्व्याख्यानेनोत्पादयितुमशक्यत्वादाह— वृद्धिशब्दस्येति । प्रत्यायनशक्तिः—प्रत्यायने–बोधजनने कारणीभूता शक्तिः । भाष्ये—उदाहरन्तीति । वृद्धिरादैजिति सूत्रार्थकथनार्थं तत्प्रदेशत्वेन 'सिचि वृद्धिः–' इत्युक्त्वा तदुदाहरणत्वेनाकार्षीत्–अक्षैषीत्–अश्रौषीदित्युदाहरन्तीत्यर्थः । एवं च वृद्धिशब्दस्य प्रत्यायकत्वमादैचां प्रत्याय्यत्वं निर्णीय वृद्धिरादैच्सूत्रस्य संज्ञाबोधकत्वं वृद्धिशब्दस्य संज्ञात्वं च निर्णयन्तीति भावः ॥ तेन—अपराचार्योक्तोदाहरणेन ॥

(आक्षेपान्तरानुवादभाष्यम्)

यदप्युच्यते—'क्रियमाणेऽपि संज्ञाधिकारे संज्ञासंज्ञिनोरसंदेहो वक्तव्यः' इति ॥

(६५ सिद्धान्तवार्तिकम् ॥ ६ ॥)

॥ * ॥ संज्ञासंज्ञ्यसंदेहश्च ॥ * ॥

(भाष्यम्)

संज्ञासंज्ञिनोश्चासंदेहः सिद्धः ॥

कुतः ?

आचार्याचारादेव । उक्त आचार्याचारः ॥

(६६ सिद्धान्तहेतुवार्तिकम् ॥ ७ ॥)

॥ * ॥ अनाकृतिः ॥ * ॥

(भाष्यम्)

अथवा—अनाकृतिः संज्ञा, आकृतिमन्तः संज्ञिनः । लोकेऽपि ह्याकृतिमतो मांसपिण्डस्य देवदत्त इति संज्ञा क्रियते ॥

(प्रदीपः) अनाकृतिरिति । आकृत्या साहचर्याद्भिदो लक्ष्यते । तेनायमर्थः—वृद्धिशब्द एकत्वात्संज्ञा, आदैचां बहुत्वात्संज्ञित्वम् । लाघवार्थं संज्ञाकरणम् । यथा—'सर्वादीनि सर्वनामानि' इत्यनेकस्यैका संज्ञा क्रियते । न त्वेकस्यानेका प्रयोजनाभावात् ॥ आकृतिमत इति । अवस्थाभेदेष्वपि स

एवायमिति प्रत्यभिज्ञानिमित्तकं देवदत्तत्वादिकं सामान्यमस्तीति 'आकृतिमतः' इत्युक्तम् ॥

(उद्द्योतः) नन्वाकृतिः=जातिस्तद्भेद आदैक्ष्वपि, तदभावस्तु न वृद्धिशब्देऽपीत्यत आह —आकृत्येति । यद्गुमीहिरिति भावः ॥ अनाकृतिरित्येतन्न्यायसिद्धमित्याह—लाघवार्थमिति ॥ नन्वेकस्यापि तव्यादेरनेकाः कृत्कृत्यप्रत्ययसंज्ञाः क्रियन्तेऽत आह-- प्रयोजनेति । सति हि प्रयोजने तथा । प्रकृते न तथा, प्रयोजनाभावादिति भावः ॥ प्रत्यभिज्ञानिमित्तकम्—प्रत्यभिज्ञाप्रमाणकमित्यर्थः । वस्तुतो भाष्ये—आकृतिमत इत्यस्य भेदवत इत्यर्थः । अवस्थाभेदेन च तत्रारोपितः सः । आरोपितभेदे च जातिसत्त्वे न मानम् । अत एव 'देवदत्ता' इत्यादौ न ङीपिति कश्चित् ॥

(६७ सिद्धान्तहेतुवार्तिकम् ॥ ८ ॥)

॥ * ॥ लिङ्गेन वा ॥ * ॥

(भाष्यम्)

अथवा—किंचिल्लिङ्गमासज्य वक्ष्यामि—इत्थंलिङ्गा संज्ञेति । वृद्धिशब्दे च तल्लिङ्गं करिष्यते, नादैच्छब्दे ॥

(प्रदीपः) **लिङ्गेन वेति** । कलादिना वर्णदोषेणेत्यर्थः ॥

(आक्षेपभाष्यम्)

इदं तावदयुक्तम् । यत्तावदुच्यते—आचार्याचारादिति ।

किमत्रायुक्तम् ?

तमेवोपालभ्य—'अगमकं ते सूत्रम्' इति, तस्यैव पुनः प्रमाणीकरणमित्येतदयुक्तम् ।

अपरितुष्यन् खल्वपि भवाननेन परिहारेण "*अनाकृतिर्लिङ्गेन वा*" इत्याह ॥

(प्रदीपः) **तमेवोपालभ्येति** । यो हि सूत्रकारमुपालभते—'अगमकं ते सूत्रं' इति, स कथं वृत्तिकारान् प्रामाण्येनाश्रयतीत्यर्थः ॥ **अपरितुष्यन्निति** । त्वयाऽपि परिहारान्तरं ब्रुवताऽऽचारो न प्रमाणत्वेनाश्रित इत्यर्थः ॥

(उद्द्योतः) **स कथं वृत्तिकारानिति** । 'तस्यैव' इति भाष्यस्य तदीयस्यैवेत्यर्थ इति भावः ॥

(तृतीयहेतौ गौरवाक्षेपभाष्यम्)

तथापि वक्तव्यम् ॥

(प्रदीपः) **तथापीति** । **'लिङ्गेन वा'** इत्येतद्वक्तव्यमित्यर्थः । **'अनाकृतिः संज्ञा'** इत्येतत्तु न्यायसिद्धत्वान्न वक्तव्यम् ॥

(उद्द्योतः) **लिङ्गेन वेत्येतदिति** । लिङ्ग=सङ्गः, इत्थं लिङ्गा संज्ञेति च वक्तव्यमित्यर्थः ॥

(तृतीयहेतुस्वीकारे लाघवप्रदर्शकभाष्यम्)

यद्यप्येतदुच्यते । अथवैतर्हि इत्संज्ञा न वक्तव्या, लोपश्च न वक्तव्यः । संज्ञालिङ्गमनुबन्धेषु करिष्यते । न च संज्ञाया निवृत्तिरुच्यते, स्वभावतः संज्ञा निवर्तते । तेनानुबन्धानामपि निवृत्तिर्भविष्यति ॥

(प्रदीपः) **अथ वैतर्हीति** । एवं सतीत्यर्थः । ङकारादिष्वनुबन्धेषु कलादिकमासज्यते । ततश्च तेषां संज्ञात्वे सति **'अनुदात्तङित आत्मनेपदं'** इति करिष्यते । संज्ञा च संज्ञिनं प्रत्याय्य स्वयं निवर्तत इतीत्संज्ञा लोपश्च न वक्तव्यौ भवत इत्यर्थः ॥

(उद्द्योतः) **ङकारादिष्विति** । धात्वादिपाठितेत्यर्थः । ननु संज्ञालिङ्गे कृतेऽपीत्संज्ञाभावे कथं तेषां निवृत्तिरत आह—भाष्ये—**स्वभावतः संज्ञेति** ॥ तद्याचष्टे—**संज्ञा संज्ञिनमिति** ॥

(आक्षेपभाष्यम्)

सिध्यत्येवम् । अपाणिनीयं तु भवति ॥

(उद्द्योतः) भाष्ये—**अपाणिनीयं त्विति** । अनन्तस्थलेषु दोषविशिष्टपठने, आनुनासिक्यादिवत् प्रतिज्ञाकरणे च दुर्ज्ञेयत्वादिति भावः ॥

(सिद्धान्तिभाष्यम्)

यथान्यासमेवास्तु ॥

(आक्षेपानुवादभाष्यम्)

ननु चोक्तम्—"*संज्ञाधिकारः संज्ञासंप्रत्ययार्थ इतरथा ह्यसंप्रत्ययो यथा लोके*" इति ॥

(अनर्थकत्वनिराकरणेन समाधानभाष्यम्)

न यथा लोके, तथा व्याकरणे । प्रमाणभूत आचार्यो दर्भपवित्रपाणिः शुचाववकाशे प्राङ्मुख उपविश्य महता प्रयत्नेन सूत्राणि प्रणयति स्म । तत्राशक्यं वर्णेनाप्यनर्थकेन भवितुम्, किं पुनरियता सूत्रेण ॥

किमतो यदशक्यम् ?

अतः संज्ञासंज्ञिनावेव ॥

(प्रदीपः) **प्रमाणभूत इति** । प्रामाण्यं प्राप्त इत्यर्थः । **'भू प्राप्तौ'** इत्यस्य **'आधृषाद्वा'** इति णिजभावपक्षे रूपम् । वृत्तिविषये च प्रमाणशब्दः प्रामाण्ये वर्तते ॥ **दर्भपवित्रेति** । प्रमादाभावं दर्शयति ॥ **प्राङ्मुख इति** । प्राच्या अभ्युदयहेतुत्वात् ॥ **महतेति** । मनःप्रणिधानं दर्शयति ॥ एतच्च सर्वमागमाद्बोद्धव्यम् । एवमानर्थक्ये परिहृते संज्ञासंप्रत्ययाय पक्षान्तराणि प्रश्नमुखेन प्रतिक्षिपति—**किमत इति** ॥

(उद्द्योतः) ननु भवतेर्जन्मार्थत्वेनाभूततद्भावप्रतीत्या च्वौ सति प्रमाणीभूत इति स्यात्, तदविवक्षायां तु प्रमाणमाचार्यः प्रकारान्तरेण भूत इति अर्थः स्यादत आह—**प्रामाण्यमिति** । 'वृत्तिविषये' इति प्रकृताभिप्रायम् ॥ **प्रमादः**–पिशाचादिसंबन्धः ॥ **आगमः**–संप्रदायः प्रकृतभाष्योक्तिर्वा ॥ भाष्ये—**अनर्थकेनेति** । बोध्यार्थरहितेनेत्यर्थः । तेन पारायणे सर्वेषामदृष्टार्थत्वेऽपि दृष्टप्रयोजनराहित्यरूपमनर्थकत्वं वर्णपदसूत्राणामस्त्येवेति न वक्ष्यमाणसूत्रादिप्रत्याख्यानासङ्गतिः ॥ **संज्ञासंप्रत्ययाय**–संज्ञात्वनिश्चयाय ॥ भाष्ये—**किमत इति** । **अतः**–तादृशकर्तृकत्वात् **किं**–कथमर्थवत्त्वं **यद्**–यतस्तद् **अशक्यनिरूपणमित्यक्षरार्थः** ॥

(संज्ञेतरार्थाक्षेपभाष्यम्)

कुतो नु खल्वेतत्—संज्ञासंज्ञिनावेवेति। न पुनः साध्वनुशासनेऽस्मिन् शास्त्रे साधुत्वमनेन क्रियते?

(उद्द्योतः) साध्वनुशासने—इत्यनेन साधुत्वपक्षस्याकाण्डता वारिता॥

(आक्षेपनिराकरणभाष्यम्)

कृतमनयोः साधुत्वम्।

कथम्?

वृधिरस्मायविशेषेणोपदिष्टः प्रकृतिपाठे, तस्मात् क्तिन्प्रत्ययः। आदैचोऽप्यक्षरसमाम्नाये उपदिष्टाः॥

(प्रदीपः) कृतमनयोरिति। आदैच्छब्दस्य द्वन्द्वत्वात् 'अनयोः' इति द्विवचननिर्देशः॥ आदैच इति। तेषां चं द्वन्द्वनिर्देशोऽयमादैच्छब्द इत्यर्थः॥

(उद्द्योतः) द्वन्द्वत्वादिति। 'अनयोः' इत्यस्य पदयोरिति विशेष्यम्। पदानामेव साधुत्वान्वाख्यानादिति भावः॥ भाष्ये—अविशेषेणेति। प्रत्ययविशेषमनादायेत्यर्थः॥ ननु वर्णसमाम्नाये आकाराद्युपदेशेऽप्यादैच्छब्दस्य किमागतमत आह—तेषां चेति। संज्ञाग्रहणद्वारेणेति शेषः॥ तपर इति आदिरन्त्येनेति च तेषां कृतयोरादैच्संज्ञयोर्द्वन्द्वनिर्देशेन द्वन्द्वशास्त्रेण कृतं साधुत्वमित्यर्थः। ऐजित्यपि तन्मूलकादिरन्त्येनेत्यनेन बोधितमित्याशयेन भाष्ये—अक्षरसमाम्नाये उपदिष्टा इत्युक्तम्॥

(आक्षेपभाष्यम्)

प्रयोगनियमार्थं तर्हीदं स्यात्—वृद्धिशब्दात्परे आदैचः प्रयोक्तव्या इति॥

(प्रदीपः) प्रयोगनियमार्थमिति। 'आदैज्वृद्धिः' इति प्रयोगो मा भूदित्यर्थः॥

(आक्षेपनिराकरणभाष्यम्)

नेह प्रयोगनियम आरभ्यते॥

किं तर्हि?

संस्कृत्य संस्कृत्य पदान्युत्सृज्यन्ते, तेषां यथेष्टमभिसंबन्धो भवति। तद्यथा-आहर पात्रम्, पात्रमाहरेति॥

(प्रदीपः) नेहेति। प्रयुज्यते-इति प्रयोगः। तस्य स्वतन्त्रस्य पदस्य प्रयुज्यमानस्य नियमो नारभ्यते, अपि तु पदावयवस्य प्रकृतिप्रत्ययोपसर्जनागमादिरूपस्य। लोके च केवल एव वृद्धिशब्दः प्रयुज्यत इति न तस्यानेन नियमः क्रियते, लोके प्रयुक्तानां हीदमनुशासनम्॥

(उद्द्योतः) ननु 'उपसर्जनं पूर्वं-परश्च' इत्यादिभिः प्रयोगनियम आरभ्यत एवेत्यत आह—प्रयुज्यत इति॥ स्वतन्त्रस्य—इति गत्युपसर्गनिरासः। तौ हि द्योतकत्वात्परतन्त्रौ॥ पदावयवस्येति। आदिना द्योतकाः॥ युक्त्यन्तरमाह—लोके चेति। शिष्टलोकाभिप्रायम्, प्रयुक्तानां चेदमनुशासनमिति भावः॥ केवल—आदैच्पदासंबद्धः॥ भाष्ये—संस्कृत्येति। साधुत्वेनान्वाख्यायेत्यर्थः॥ अभिसंबन्धः—पौर्वापर्यलक्षणः॥

(आक्षेपभाष्यम्)

आदेशास्तर्हीमे स्युः। वृद्धिशब्दस्यादैचः॥

(आक्षेपनिराकरणभाष्यम्)

षष्ठीनिर्दिष्टस्यादेशा उच्यन्ते। न चात्र षष्ठीं पश्यामः॥

(प्रदीपः) षष्ठीनिर्दिष्टस्येति। स्थानशब्दोऽर्थवाची, तिष्ठन्त्यस्मिञ्शब्दा इति स्थानम्। न च वृद्धिशब्दार्थमादैचो वक्तुं शक्ताः, तेनात्र षष्ठ्यर्थाभावादिति तात्पर्यम्। तथाहि षष्ठ्यभावेऽपि तदर्थसद्भावाद्भवत्येव स्थान्यादेशभावः। यथा—'नाभि नभं च' 'परश्री परशुं च' इति॥

(उद्द्योतः) षष्ठ्यभावेऽपि 'नाभि नभं' इत्यादावादेशदर्शनादाह—स्थानेति। सूत्रगत इति शेषः। तत्र हि सूत्रे स्थानशब्दोऽधिकरणव्युत्पत्त्याऽर्थवाची भावव्युत्पत्त्या प्रसङ्गवाची च तन्त्रेणोपादीयते। अन्यथा केवलार्थशब्दं प्राप्तिशब्दं वोपाददीत। एवं च—याऽनिर्देश्या षष्ठी सा प्रसङ्गनिरूपितसंबन्धार्थिकैवेत्येकोऽर्थः। द्वितीये तु षष्ठीशब्दो लक्षणया स्थानिपरः। 'स्थाने' इति सप्तमी वाच्यस्यार्थस्याधिकरणत्वविवक्षया बोध्या। योगशब्दश्च युज्यत इति व्युत्पत्त्या आदेशवाची, ततोऽर्शआद्यच्। तेन स्थानी स्वार्थाभिधानसमर्थादेशवानित्यर्थ इति भावः॥ भाष्यस्य तु षष्ठीनिर्दिष्टस्य स्थानिनो योऽर्थस्तस्य वाचका उच्यन्ते। न चात्रादैक्षु षष्ठीनिर्दिष्टस्य स्थानिनोऽर्थमभिधेयत्वेन पश्याम इत्यर्थः॥ षष्ठ्यर्थाभावादिति। षष्ठीबोध्यस्थान्यर्थाभिधानसामर्थ्याभावादिति भावः॥ तदर्थसद्भावादिति। आदेशस्य स्थान्यर्थबोधनसामर्थ्यसद्भावादित्यर्थः॥ वस्तुतस्तु स्थानं—प्रसङ्ग एव। स चार्थवत एव, अर्थप्रत्यायनाय शब्दप्रयोगात्। एवं चार्थप्रयुक्त एव स्थान्यादेशयोः संबन्ध इति स्थान्यर्थाभिधानसमर्थस्यैवादेशतेति वदन्ति॥

(आक्षेपभाष्यम्)

आगमास्तर्हीमे स्युः। वृद्धिशब्दस्यादैच आगमाः॥

(आक्षेपनिरासभाष्यम्)

आगमा अपि षष्ठीनिर्दिष्टस्यैवोच्यन्ते, लिङ्गेन च। न चात्र षष्ठीं, न खल्वप्यागमलिङ्गं पश्यामः॥

(प्रदीपः) आगमा अपीति। अत्राप्यर्थोऽपेक्ष्यते। अनागमकानामर्थे सागमका इत्यर्थः॥ लिङ्गेन चेति। देशविशेषप्रतिपत्तये टकारादिलिङ्गं तत्र क्रियत इत्यर्थः॥

(उद्द्योतः) अत्रापीति। वस्तुतोऽत्र षष्ठ्यैवागमा उच्यन्ते इत्यर्थः॥ कलादिलिङ्गभ्रमव्यावृत्तये आह—देशेति। देशविशेषप्रतिपत्त्यर्थयत्नसाध्यागमप्रतीतिर्यत्नाभावे नेत्यर्थः॥

(सिद्धान्तसमाधानभाष्यम्)

इदं खल्वपि भूयः सामानाधिकरण्यमेकविभक्तित्वं च। द्वयोश्चैतद्भवति।

कयोः?

विशेषणविशेष्ययोर्वा, संज्ञासंज्ञिनोर्वा ।

तत्रैतत्स्यात्—विशेषणविशेष्ये इति ।

तच्च न, द्वयोर्हि प्रतीतपदार्थकयोर्लोके विशेषणविशेष्यभावो भवति । न चादैच्छब्दः प्रतीतपदार्थकः ।

तस्मात्संज्ञासंज्ञिनावेव ॥

(प्रदीपः) **इदं खल्वपीति** । विशेषणविशेष्यभावनिराकरणेन संज्ञापक्षं स्थापयति ॥ 'देवदत्तः पचति' इत्यस्ति सामानाधिकरण्यं न त्वेकविभक्तित्वम्, 'गौः-अश्वः' इत्यस्त्येकविभक्तित्वं न तु सामानाधिकरण्यं—इत्युभयोरुपादानम् । संज्ञासंज्ञिनोरप्यस्ति विशेषणविशेष्यत्वं प्रसिद्ध्यप्रसिद्धिवशात्तु भेदेनोपादानम् । तत्तु सामानाधिकरण्यं शब्दयोरेव केचिदिच्छन्ति, द्वाभ्यां भिन्नप्रवृत्तिनिमित्ताभ्यामेकस्याधिकरणस्याभिधेयस्य प्रतिपादनाद्विशेषणविशेष्यार्थप्रतिपादनाच्च विशेषणविशेष्यत्वम् । **अन्ये तु** नीलमुत्पलमिति प्रवृत्तिनिमित्तयोर्जातिगुणयोरेकमधिकरणमाश्रय इति सामानाधिकरण्यं विशेषणविशेष्यभावं चार्थयोरेव मन्यन्ते ॥ **न चादैच्छब्द इति** । न ह्यस्य कश्चिल्लौकिकोऽर्थः प्रसिद्ध इत्यर्थः ॥

(उद्योतः) **इदं** खल्वपीति भाष्यं पूर्वोक्तपक्षाणामसंभवं प्रतिपादयति ॥ **अस्ति सामानाधिकरण्यमिति** । न च तादृशे संज्ञासंज्ञित्वसंभावनेति भावः ॥ **इत्युभयोरिति** । विशेषणविशेष्यत्वसंज्ञासंज्ञित्वसंभावनास्थलप्रदर्शनायेत्यर्थः ॥ **संज्ञासंज्ञिनोरपीति** । उद्भिदादिसंज्ञा हि स्वरूपेणैव संज्ञिनं सजातीयाद्यागान्तराद्विजातीयाच्च होमादेर्व्यवच्छिनत्तीति विशेषणम् । संज्ञी च व्यवच्छेद्यः सन्विशेष्यः । विषयताविशेषरूपमपि तयोरस्त्येवेति भावः ॥ **प्रसिद्धीति । 'द्वयोर्हि प्रतीत–'** इत्यादिना भाष्ये उक्तमेतत् । **यद्वा** सत्यपि व्यवच्छेद्यव्यवच्छेदकभावे संज्ञासंज्ञिनोर्विशेष्यविशेषणभावो लोके न प्रसिद्ध इत्यर्थः ॥ ननु सामानाधिकरण्यं नाम द्वयोः शब्दयोरेकाभिधेयसंबन्धः, तत्तु न युक्तम् । सामानाधिकरण्यस्य शब्दधर्मत्वेन विशेषणत्वादेश्चार्थधर्मत्वेन **विशेषणविशेष्ययोः सामानाधिकरण्यमिति** भाष्यासङ्गतिः, संज्ञासंज्ञिनोरेकाभिधेयसंबन्धाभावेन **संज्ञासंज्ञिनोर्वा सामानाधिकरण्यमि**त्यस्याप्यसङ्गतिरत आह—**तत्त्विति** ॥ **भिन्नप्रवृत्तीति** । अनेन पर्यायनिरासः । वस्तुत इदं चिन्त्यम्, **आर्ये देवि सरस्वति इडे काव्ये विहव्ये पुतानि तेऽघ्न्ये नाम**।नीत्यादौ नामभिन्ने समानाधिकरणे इत्यस्य व्यावृत्तये तत्र सामान्यवचनग्रहणमिति तत्सत्रस्थभाष्यविरोधापत्तेः । युगपदधिकरणवचनतापक्षे पट्वीमृद्व्याविति तत्र समानाधिकरणलक्षणपुंवद्भावशङ्कापरभाष्यविरोधापत्तेश्च ॥ विशेषणत्वादिकं चोपपद्यत इत्याह—**विशेषणेति** । भाष्ये **'संज्ञासंज्ञिनोः'** इत्यत्र संज्ञिपदेन संज्ञिसमर्पकः शब्दोऽभिप्रेतः । संज्ञाशब्दे च शब्दः प्रवृत्तिनिमित्तं, संज्ञिनि तत्सम्बन्धात् । संज्ञिबोधकशब्दे च संज्ञिगततत्तद्धर्मः प्रवृत्तिनिमित्तम् । एवं च वृद्धिशब्दवदभिन्ना आदैच इति बोधः । वृद्धिशब्दवत्त्वं च लोकसिद्धतादात्म्येनेत्याशयः ॥ **अन्ये त्विति** । संज्ञासंज्ञिनोस्तूक्तं प्रवृत्तिनिमित्तमिति सामानाधिकरण्यम् । एकविभक्तिकत्वं त्वत्र पक्षे शब्दद्वारा बोध्यम् । विभक्तिशब्देन शक्तो । भाष्ये **संज्ञासंज्ञिनोरित्यस्य** तत्प्रवृत्तिनिमित्तयोरित्यर्थः ॥ 'अन्ये तु' इति मतेऽरुचिबीजं तु **प्रतीतपदार्थकयोरिति** बहुव्रीहिस्वरसभङ्गः ॥ **विशेषणविशेष्यभावो भवती**त्यस्य तदर्थप्रतिपादकत्वं भवतीत्यर्थः ॥ ननु वैयाकरणानामादैच्छब्दः प्रतीतपदार्थक एवेत्यत आह—**न हीति** । वृद्धिशब्दार्थान्वययोग्य इति शेषोऽत्र द्रष्टव्यः ॥ केचित्तु वृद्ध्यादिशब्दाः शब्दपरा एव । वृद्धिशब्दाभिन्ना आदैच इति बोधः । तदुक्तं हरिणा—

> "वृद्ध्यादयो यथा शब्दाः स्वरूपोपनिबन्धनाः ।
> आदैच्प्रत्यायितैः शब्दैः सम्बन्धं यान्ति संज्ञिभिः ॥"

इति । सामानाधिकरण्यं चैकविशेष्यकप्रतीतिजनकत्वमित्याहुः ॥

(सिद्धान्तभाष्यम्)

तत्र त्वेतावान्संदेहः—कः संज्ञी का संज्ञेति ॥

स चापि क्व सन्देहः—यत्रोभे समानाक्षरे ।

यत्र त्वन्यतरल्लघु सा संज्ञा ॥

कुत एतत् ?

लघ्वर्थं हि संज्ञाकरणम् ॥ तत्राप्ययं नावश्यं गुरुलघुतामेवोपलक्षयितुमर्हति ।

किं तर्हि ?

अनाकृतितामपि । अनाकृतिः संज्ञा, आकृतिमन्तः संज्ञिनः । लोके ह्याकृतिमतो मांसपिण्डस्य देवदत्त इति संज्ञा क्रियते ॥

(उद्योतः) भाष्ये—**यत्रोभे इति** । प्रत्यय अनीयरित्यादौ ॥ **लघ्वर्थमित्यस्य** लाघवार्थमित्यर्थः ॥

(समाधानान्तरभाष्यम्)

अथवा-आवर्तिन्यः संज्ञा भवन्ति । वृद्धिशब्दश्चावर्तते, नादैच्छब्दः । तद्यथा—इतरत्रापि देवदत्तशब्द आवर्तते, न मांसपिण्डः ॥

(प्रदीपः) **आवर्तिन्य इति** । देवदत्तादिशब्दा हि दानादिप्रतिपादनायावर्त्यन्ते ॥

(उद्योतः) **न मांसपिण्ड इति** । दूरस्थस्यापि नामोच्चारणमात्रेण दानादिसंभवादिति भावः ॥

(समाधानान्तरभाष्यम्)

अथवा—पूर्वोच्चारितः संज्ञी, परोच्चारिता संज्ञा ॥

कुत एतत् ?

सतो हि कार्यिणः कार्येण भवितव्यम् । तद्यथा—इतरत्रापि सतो मांसपिण्डस्य देवदत्त इति संज्ञा क्रियते ॥

(प्रदीपः) **अथवेति** । सत्यसति वा संज्ञिनि बुद्ध्या विषयीकृते शब्देन पूर्वनिर्दिष्टे संज्ञा प्रवर्तत इत्यर्थः ॥ ततश्च **'अदेङ् गुणः'** इत्यादावदेङादयः संज्ञिनो गुणादयः संज्ञाः ॥

(उद्योतः) **सतो** हीत्यादिना न भावरूपं विवक्षितम्,

अभावस्यापि लोपादिसंज्ञादर्शनात् । नापि विद्यमानत्वं, प्रत्ययविधौ संज्ञाविशिष्टस्यापि विधानादत आह—बुध्येति । अत एव सावर्णि-मैत्रिता मनुरित्यादौ न दोषः । एवं च सच्छब्देन पूर्वं बुद्ध्या विषयीकृतत्वं विवक्षितमित्यर्थः । बुद्धिसत्तासमाविष्ट एव चार्थः शब्देन बोध्यत इति सिद्धान्तात् ॥ तस्य हि पूर्वोच्चारितस्यैव भवतीत्याह—शब्देन पूर्वेति ॥

(आक्षेपभाष्यम्)

कथं "वृद्धिरादैच्" इति ?

(समाधानभाष्यम्)

एतदेकमाचार्यस्य मङ्गलार्थं मृष्यताम् । माङ्गलिक आचार्यो महतः शास्त्रौघस्य मङ्गलार्थं वृद्धिशब्द-मादितः प्रयुङ्क्ते । मङ्गलादीनि हि शास्त्राणि प्रथन्ते वीरपुरुषाणि च भवन्ति, आयुष्मत्पुरुषाणि च । अध्येतारश्च वृद्धियुक्ता यथा स्युरिति ॥

सर्वत्रैव हि व्याकरणे पूर्वोच्चारितः संज्ञी, परो-च्चारिता संज्ञा । "अदेङ् गुणः" इति यथा ॥

(प्रदीपः) इह तु मङ्गलार्थोऽन्यथा पाठक्रमः । आर्थस्त्व-न्यथा क्रमः । अन्ये तु सिद्धिहेतवो भविष्यन्ति ॥ 'अपृक्त एकाल्प्रत्ययः' इति तु परिभाषा, न संज्ञेति नास्ति व्यभिचारः । अपृक्तशब्देन ह्येकाकी कथ्यत इति अनियमेन ग्रहणे प्राप्ते नियमः क्रियते ॥

(उद्योतः) भाष्ये—माङ्गलिकः—मङ्गलप्रयोजनः ॥ महतः—अर्थतः ॥ एकैकं सूत्रं शास्त्रमिति शास्त्रौघस्येत्युक्तम् ॥ मङ्गला-दीनीत्यादिना स्वप्रयोजनं श्रोतृप्रयोजनं चोक्तम् ॥ प्रथन्ते—विस्तृ-तानि भवन्ति । तेन समाप्तिरर्थाक्षिप्ता ॥ आर्थस्त्वन्यथेति । आदैच् वृद्धिरित्याकारः । आनुपूर्वीज्ञानस्यासत्तिविधया हेतुत्वादिति भावः ॥ कथं तर्हि वृद्धिशब्दस्य संज्ञात्वप्रतीतिरत आह—अन्ये त्विति । लाघवादयः । आदैचो वृद्धिपदाभिन्ना इत्यर्थः । एवंचानु-पूर्वीव्यत्यासेन विलम्बेन बोधजनकशब्दोच्चारणं मङ्गलार्थं क्षम्यतामिति बोध्यम् । अत्रैकशब्दः प्रथमार्थकः, प्रथमं तथाकरणं मङ्गलार्थमेव । एवं चान्यत्रापि तथाकरणमुद्देश्यविधेयभावेनान्वये तादृशस्यैव साधुत्व-मिति भ्रमवारणार्थमित्याहुः ॥ परिभाषेति । तदा हि यत्रापृक्तपदं तत्रैकालित्याद्युपतिष्ठत इत्यर्थात्प्राथम्यं युक्तमेवेत्यर्थः । वस्तुत इदं वृद्धिसूत्रेऽपि सुवचम् । किं चैवमपृक्तसंज्ञायामित्यादि भाष्यवार्तिक-व्यवहारानुपपत्तिः ॥ केचित्तु परिभाषात्वेऽपि एकाल्प्रत्ययोद्देशेना-पृक्तपदवद्देशस्तत्वं विधेयम्, पदपरत्वार्थं तथापि लक्षणाऽऽवश्यकत्वेन सामानाधिकरण्यान्वयार्थं तावत्पर्यन्तं लक्षणाया उचितत्वात् । पदत्रया-ध्याहारे गौरवाच्च । एवं च परिभाषात्वेऽप्युद्देश्यत्वेन तस्यैव पूर्वं पाठो युक्तः । आनुपूर्वीव्यत्यासाद्बोधस्तूभयोः सम इति वदन्ति ॥

(सिद्धान्तिभाष्यम्)

दोषवान्खल्वपि संज्ञाधिकारः । अन्त्येऽपि हि संज्ञा क्रियते—"तस्य परमाम्रेडितम्" इति । तत्रा-पीदमनुवर्त्यं स्यात् ॥

(उद्योतः) भाष्ये—अनुवर्त्यं स्यादिति । तच्चासंदिग्धेङ्ग-ङ्गबाधादशक्यमिति भावः ॥

(समाधानान्तरभाष्यम्)

अथवा–अस्थानेऽयं यत्नः क्रियते । न हीदं लोका-द्भिद्यते, यदीदं लोकाद्भिद्येत ततो यत्नार्हं स्यात् । तद्यथा—अगोज्ञाय कश्चिद्गां सक्थनि कर्णे वा गृहीत्वोपदिशति—अयं गौरिति । न चास्माया चष्टे 'इयमस्य संज्ञा' इति । भवति चास्य संप्रत्ययः ॥

(प्रदीपः) अस्थान इति । अन्तरेणापि संज्ञाशब्दप्रयोगं लोकव्यवहारवदत्र संज्ञासंज्ञिसंबन्धः सिध्यतीत्यर्थः ॥

(उद्योतः) (भाष्ये) अस्थाने—अनवसरे । भिद्यते—विलक्षणं भवतीत्यर्थः ॥

(आक्षेपभाष्यम्)

तत्रैतत्स्यात्—'कृतस्तत्र पूर्वैरभिसंबन्धः' इति ॥

(उद्योतः) अभिसंबन्धः—संज्ञासंज्ञिभावः । ततो ज्ञातुं शक्य इति भावः ॥

(समाधानभाष्यम्)

इहापि कृतः पूर्वैरभिसंबन्धः ।
कैः ?
आचार्यैः ॥

(आक्षेपभाष्यम्)

तत्रैतत्स्यात्—यस्मै तर्हि सम्प्रत्युपदिशति तस्या-कृत इति ॥

(उद्योतः) तस्याकृत इत्यस्य तेनाज्ञात इत्यर्थः । तथा च तेन कथं प्रतिपत्तुं शक्य इति भावः ॥

(समाधानभाष्यम्)

लोकेऽपि हि यस्मै सम्प्रत्युपदिशति तस्याकृतः । अथ तत्र कृतः, इहापि कृतो द्रष्टव्यः ॥

(उद्योतः) अथ तत्रेति । अनुमानादिना ज्ञात इत्यर्थः ।

(इति संज्ञासूत्रत्वसाधनम्)

—•—

(अन्योन्याश्रयपरिहाराधिकरणम्)

(६८ संज्ञासंज्ञिभावाक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ सतो वृद्ध्यादिषु संज्ञाभावात्तदा-श्रय इतरेतराश्रयत्वादप्रसिद्धिः ॥ * ॥

(भाष्यम्)

सतः संज्ञिनः संज्ञाभावात् तदाश्रये संज्ञिनि वृद्ध्यादिष्वितरेतराश्रयत्वादप्रसिद्धिः ॥

का इतरेतराश्रयता ?

सतामादैचां संज्ञया भवितव्यम्, संज्ञया चादैचो भाव्यन्ते । तदितरेतराश्रयं भवति । इतरेतराश्रयाणि च कार्याणि न प्रकल्पन्ते । तद्यथा—नौर्नावि बद्धा

नेतरेतराश्रयाणाय भवति ॥

(प्रदीपः) सतो वृद्ध्यादिष्विति । विधौ चायं दोषः, नानुवादे—'वृद्धिर्यस्य—' इत्यादौ । तत्र च संज्ञाविधानस्य चरितार्थत्वात् 'मृजेर्वृद्धिः' इत्यादौ वृद्धिशब्द एवादेशः प्राप्नोति ॥

(उद्द्योतः) सतो वृद्ध्यादिष्विति । सतः—निष्पन्नस्य संज्ञाभावात्—संज्ञासंबन्धात् तदाश्रये—संज्ञाश्रये संज्ञया संज्ञिविधायके शास्त्रे मृजेर्वृद्धिरित्यादौ वृद्ध्यादिषु—वृद्ध्यादिपदेषु इतरेतराश्रयत्वादप्रसिद्धिः—वाक्यार्थाप्रसिद्धिरित्यर्थः । अविद्यमाने संबन्धस्य वक्तुमशक्यत्वादिति भावः ॥

(इतरेतराश्रयिदृष्टान्तभाष्यम्)

ननु च भोः—इतरेतराश्रयाण्यपि कार्याणि दृश्यन्ते । तद्यथा—नौः शकटं वहति, शकटं च नावं वहति ॥

(प्रदीपः) ननु च भो इति । नौशकटस्याभिमतदेशान्तरप्राप्तिरितरेतराश्रयेति चोद्यम् ॥

(उद्द्योतः) वहनक्रियायामितरेतराश्रयत्वाभावेऽपि तत्फलत्वीत्याह—(भाष्ये) नौः शकेति ॥

(दृष्टान्तनिरासभाष्यम्)

अन्यदपि तत्र किंचिद्भवति—जलं स्थलं वा । स्थले शकटं नावं वहति । जले नौः शकटं वहति ॥

(इतरेतराश्रयिदृष्टान्तान्तरभाष्यम्)

यथा तर्हि त्रिविष्टब्धकम् ॥

(दृष्टान्तान्तरनिराकरणभाष्यम्)

तत्राप्यन्ततः सूत्रकं भवति ॥

(प्रदीपः) सामर्थ्यन्तरानुप्रवेशेनोत्तरम् ॥

(उद्द्योतः) सामर्थ्यन्तरेति । कारणान्तरेत्यर्थः ॥ सूत्रकंकीलादि ॥ न च सामान्यलक्षणया भूतभाविसकलविषयकशक्तिग्रहः संभवत्येव । अन्यथा तत्रापि तत्तद्बोद्धबुद्धौ असंनिहितसकलाकारविषयकशक्तिग्रहासंभवेनानुवादेऽपि दोषः स्यात् । सामान्यलक्षणाऽनङ्गीकारेऽपि शक्तिग्रहबोधादीनां समानप्रकारकत्वेनैव कार्यकारणभावाभ्युपगमान्न दोष इति वाच्यम् । जातिप्रकारकशक्तिग्रहस्य स्वाश्रयीभूतसकलव्यक्तिबोधकत्वेऽप्यनुपलम्भे जात्याश्रयत्वसंबन्धस्य वक्तुमशक्यतया भाविव्यक्तेर्जात्याश्रयत्वाभावात् तद्बोधासंभवेन मृजेर्वृद्धिरित्यत्र तज्जन्योत्पत्तिज्ञप्त्योः परस्पराश्रय इति भावात् । वृद्धिरादैजित्यस्य विद्यमानेषु बुद्धिस्थेषु चारितार्थ्येन भाविनामुद्देश्यत्वासंभवेन तत्र वृद्धिपदस्य शक्तिग्रहासंभवाच्च ॥

(आक्षेपोपसंहारभाष्यम्)

इदं पुनरितरेतराश्रयमेव ॥

(६९ अन्योन्याश्रयवारकसिद्धान्तिवार्तिकम् ॥ २ ॥)

॥ * ॥ सिद्धं तु नित्यशब्दत्वात् ॥ * ॥

(भाष्यम्)

सिद्धमेतत् ।
कथम् ?
'नित्यशब्दत्वात्' । नित्याः शब्दाः, नित्येषु शब्देषु सतामादैचां संज्ञा क्रियते, न संज्ञया आदैचो भाव्यन्ते ॥

(प्रदीपः) सिद्धं त्विति । न हि मृजेर्वृद्धिरपूर्व आकारो भाव्यते किं तु मृजावुपदिष्टे मार्ष्टीत्यादीनामसाधुत्वबुद्धिः प्राप्नोतीति तेषां साधुत्वान्वाख्यानं क्रियते ॥

(उद्द्योतः) यद्यप्यस्य सूत्रस्य शाटकं वयेत्यादाविव भाविसंज्ञाविज्ञानेन सिध्यति, यथा च तत्रोत्पत्त्यनन्तरं गृहीतशक्तिकशाटकसादृश्याच्छाटकपदशक्तिग्रहस्तथा प्रकृतेऽपि स्पष्टं चेदमिग्यण इति सूत्रे भाष्ये, तथाप्यत्र वास्तवमेव परिहारमाह—भाष्ये—सिद्धं त्विति । एतच्च मञ्जूषायां विस्तरेण निरूपितम् ॥

(आक्षेपभाष्यम्)

यदि तर्हि नित्याः शब्दाः, किमर्थं शास्त्रम् ?

(आक्षेपवारकं भाष्यवार्तिकम् ॥)

किमर्थं शास्त्रमिति चेन्निवर्तकत्वात्सिद्धम् ॥

(भाष्यम्)

निवर्तकं शास्त्रम् ।
कथम् ?
मृजिरस्मायविशेषेणोपदिष्टः । तस्य सर्वत्र मृजिबुद्धिः प्रसक्ता । तत्रानेन निवृत्तिः क्रियते—मृजेरक्त्सु प्रत्ययेषु मृजेः प्रसङ्गे मार्जिः साधुर्भवतीति ॥

(इत्यन्योन्याश्रयनिराकरणम् ।)

(अथ समुदितसंज्ञानिराकरणाधिकरणम्)

(वार्तिकावतरण आक्षेपभाष्यम्)

प्रत्येकं वृद्धिगुणसंज्ञे भवत इति वक्तव्यम् ।
किं प्रयोजनम् ?
समुदाये मा भूतामिति ॥

(प्रदीपः) प्रत्येकमिति । यद्यपि नित्यशब्दत्वेनैतदपि व्यवतिष्ठते, तथापि न्यायव्युत्पादनायोपन्यासः ॥ **समुदाये मा भूतामिति** । अन्यथा 'मृजेर्वृद्धिः' इत्यादौ समुदाय आदेशः प्राप्नोति । समुदायावयवसन्निधौ क्व तात्पर्यं कस्य च नान्तरीयकत्वमिति विचार्यते ॥

(उद्द्योतः) न्यायेति । वक्ष्यमाणन्यायद्वयेत्यर्थः ॥ ननु वृद्धिर्यस्येत्यादौ समुदायासंभवात् प्रत्येकमेव संज्ञेत्यत आह—अन्यथेति । एवं च तमादाय तत्रापि संभवः । द्वन्द्वनिर्देशात्समुदायस्यैव स्यादिति भावः ॥ समुदायेति । 'मातापित्रोर्मृतेऽहनि' इतिवद्बोधे साहित्यं न तु क्रियानिष्पत्तौ—इति भावः ॥

(७० आक्षेपवारकसिद्धान्तिवार्तिकम् ॥ ३ ॥)

॥ * ॥ अन्यत्र सहवचनात्समुदाये संज्ञाऽप्रसङ्गः ॥ * ॥

(भाष्यम्)

अन्यत्र सहवचनात्समुदाये वृद्धिगुणसंज्ञयोर-

प्रसङ्गः। यत्रेच्छति सहभूतानां कार्यं, करोति तत्र सहग्रहणम्। तद्यथा-"सह सुपा" "उभे अभ्यस्तं, सह" इति॥

(प्रदीपः) अन्यत्रेति। यत्रसाध्या समुदायप्रतिपत्तिरिति यत्राभावे न भवतीत्यर्थः॥ ननु सहग्रहणं नियमार्थं स्यात्-समुदायस्यैव समाससंज्ञा यथा स्यात्, नावयवानामिति। नैतदस्ति, उभयत्र तात्पर्याभावायुगपदुभयत्र प्रसङ्गाभावाल्लिङ्गत्वमेव सहग्रहणस्यान्यत्र समुदाये तात्पर्यं नास्तीत्यस्यार्थस्य॥ उभे अभ्यस्तं सहेति। अत्र सहग्रहणं वार्तिककारस्य कर्तव्यत्वेन स्थितम्। भाष्यकारस्तूभेग्रहणस्यैतत्प्रयोजनं स्थापयिष्यति॥

(उद्द्योतः) उभयत्रेति। समुदायेऽवयवे चेत्यर्थः॥ उभयत्र तात्पर्याभावे हेतुः— युगपदिति। फलाभावादिति भावः॥ यद्यपि पर्यायः प्राप्नोति, तथापि समासविधिनियमोभयपरत्वे गौरवमित्यतो लिङ्गत्वकल्पनमेवोचितमित्यत्र तात्पर्यम्॥ भाष्यकारस्त्विति। तदेकदेशीत्यर्थः। द्वे इत्यनुवृत्त्यैव सिद्धे उभेग्रहणं सहार्थकमिति भावः॥

(७१ आक्षेपवारकसिद्धान्तिवार्तिकम्॥ ४॥)

॥ * ॥ प्रत्यवयवं च वाक्यपरिसमाप्तिः॥ *॥

(भाष्यम्)

प्रत्यवयवं च वाक्यपरिसमाप्तिर्दृश्यते। तद्यथा—देवदत्तयज्ञदत्तविष्णुमित्रा भोज्यन्तामिति। न चोच्यते प्रत्येकमिति। प्रत्येकं च भुजिः परिसमाप्यते॥

(प्रदीपः) प्रत्यवयवं चेति। अत्र वाक्यशब्देन वाक्यार्थफलमुच्यते। तच्च देवदत्तादीनां भोजनम्। तस्य चैतदेव रूपं यत्प्रत्येकपरिसमाप्त्या संपद्यते। अन्नादनादिरूपत्वात्तृप्तिफलत्वाच्च भोजनस्य। नाट्यक्रिया तु समुदाये समाप्यते, गीतादिक्रियासमुदायरूपत्वात्तस्याः। संयोगसंज्ञा त्वन्वर्थत्वात्समुदाये प्रवर्तते। वृद्धिसंज्ञा तु लक्ष्ये पृथगादैचां दर्शनात् 'मालादीनां च' इति लिङ्गाच्च प्रत्येकमवतिष्ठते॥

(उद्द्योतः) न ज्ञापकादेव, किं तु युक्तितोऽपि प्रत्येकं संबन्धमित्याह—भाष्ये-प्रत्यवयवमिति॥ ननु प्रत्येकं वाक्यपरिसमाप्तिमुपक्रम्य प्रत्येकं भुजिसमाप्त्युक्तिरयुक्ता, न हि भुज्यर्थोऽत्र वाक्यार्थः। किं तु ण्यन्तार्थोऽत आह—अत्रेति॥ वाक्यार्थस्तु अत्र प्रयोजकव्यापारस्तस्य समुदायविषयत्वसंभवात्फलग्रहणम्। तच्च प्रयोज्यव्यापाररूपमित्याह—तच्चेति॥ ननु विशिष्टपरिमाणस्यादनीयस्य भोजनक्रिया समुदाये पर्यवसेत्यपि वक्तुं शक्यमत आह—तृप्तिफलत्वाच्चेति॥ सर्वाऽपि क्रिया प्रत्येकं समाप्यत इति भ्रमो न कार्य इत्याह—नाट्येति॥ गीतादीति। आदिना नृत्तवाद्यादि॥ अन्वर्थत्वात्—संयुज्यन्ते वर्णा अत्रेति॥ लक्ष्यानुसारात्तत्र समुदाये वाक्यपरिसमाप्तेराश्रयणमिति तत्त्वम्॥ प्रकृतेऽन्यतरन्यायाश्रयणहेतुमाह—वृद्धिसंज्ञेति॥ लिङ्गादिति। प्रस्थेऽवृद्धमिति निषेधबाधनार्थं हि तदिति भावः॥ न च नामधेयरूपमालादीनामाद्युदात्तार्थं तत्, तस्य वा नामधेयस्येति पक्षे वृद्धत्वादिति वाच्यम्। अभिव्यक्तेति न्यायेन तत्राप्रवृत्तेः॥

(आक्षेपभाष्यम्)

ननु चायमप्यस्ति दृष्टान्तः—'समुदाये वाक्यपरिसमाप्तिः' इति। तद्यथा—'गर्गाः शतं दण्ड्यन्ताम्' इति। अर्थिनश्च राजानो हिरण्येन भवन्ति, न च प्रत्येकं दण्डयन्ति॥

(प्रदीपः) गर्गा इति। अत्र शतस्येप्सिततमत्वात् प्राधान्यम्, अपादानस्थानप्राप्ता गर्गा गुणकर्म, 'न च गुणभेदे प्रधानस्य भेदः' इति शतदण्डनं समूहे परिसमाप्यते॥ अर्थिनश्चेति। शतस्य प्राधान्यं प्रतिपाद्यते। दण्डपरायां चोदनायां शतस्य प्राधान्यमतो वाक्यादवगम्यते॥

(उद्द्योतः) समुदाये समाप्तौ युक्तिमाह—अत्र शतस्येति। एवं चाकथितसंज्ञे दण्डिरपि परिगणनीय इति भाव इत्येके॥ उद्देश्यत्वरूपमार्थं प्राधान्यं शतस्येत्यनुद्देश्यत्वेन गर्गा गुणकर्म। दण्डेश्च स्वसंप्रदानकदानानुकूलव्यापारानुकूलव्यापारः शासनरूपोऽर्थः। शासनं—नियन्त्रणम्। तत्र ण्यन्त इव 'कर्तुः—' इत्युभयोः कर्मत्वम्। कर्तृप्रत्ययसमभिव्याहारे धात्वर्थप्रधानव्यापारविशेषणफलाश्रयत्वेन गर्गाणां शब्दं प्राधान्यम्। तत्रैव प्रधाने कर्मणि लकारः। "प्रधानकर्मण्याख्येये लादीनाहुर्द्विकर्मणाम्" इत्युक्तेः। दुहादिष्वस्याप्रामाणिकः पाठ इति वक्ष्यते॥ अपादानस्थानप्राप्ता इत्यनेन चानुद्देश्यत्वमात्रमभिप्रेतमिति परे॥ शतस्य प्राधान्यमिति। शारीराभिहननलक्षणदण्डव्यावर्तनेनेति भावः

(समाधानभाष्यम्)

सत्येतस्मिन्दृष्टान्ते यदि तत्र सहग्रहणं क्रियते, इहापि प्रत्येकमिति वक्तव्यम्।

अथ तत्रान्तरेण सहग्रहणं सहभूतानां कार्यं भवति, इहापि नार्थः प्रत्येकमिति वचनेन॥

(प्रदीपः) अथ तत्रान्तरेणेति। न्यायादन्वर्थत्वाच्च समाससंज्ञायाः समुदाये परिसमाप्तौ सिद्धायां योगविभागार्थं तत्र सहग्रहणं स्थितमिति 'तत्रान्तरेण' इत्युक्तम्॥

(उद्द्योतः) ननु 'अन्तरेणापि' इति वाच्ये सार्वकालिकासत्त्वप्रतिपादकमपिशब्दरहितमयुक्तमत आह—न्यायादिति। शतदण्डनन्यायेत्यर्थः॥ योगविभागेति। तिङन्तसमासायेति भावः॥

(इति समुदायसंज्ञानिराकरणम्।)

(अथ तपरग्रहणनिराकरणीयाधिकरणम्)

(आक्षेपभाष्यम्)

अथ किमर्थमाकारस्तपरः क्रियते?

(प्रदीपः) अथ किमर्थमिति। किमाकृतिपक्षे भिन्न-

कालनिवृत्त्यर्थम्, अथवा व्यक्तिपक्षे गुणान्तरयुक्तानां ग्रहणार्थमिति प्रश्नः ॥

(उद्द्योतः) भाष्ये—किमर्थमिति—चतुर्थीतत्पुरुषः ॥

(७३ सिद्धान्तसमाधानवार्तिकम् ॥ १ ॥)

॥ * ॥ आकारस्य तपरकरणं सवर्णार्थम् ॥ * ॥

(भाष्यम्)

आकारस्य तपरकरणं क्रियते ।

किं प्रयोजनम् ?

सवर्णार्थम् । "तपरस्तत्कालस्य" इति तत्कालानां सवर्णाना ग्रहणं यथा स्यात् ।

केषाम् ?

उदात्तानुदात्तस्वरितानाम् ॥

(प्रदीपः) **आकारस्येति** । व्यक्तिः पदार्थो भेदकाश्च गुणा इति दर्शने यद्गुणस्यैवोच्चारणं तद्गुणस्यैव संज्ञाप्रसङ्गे गुणान्तरयुक्तानामपि संज्ञाप्रतिपत्त्यर्थं तपरत्वमित्यर्थः ॥

(उद्द्योतः) (भाष्ये) तपरकरणं क्रियत इति । 'पाकं पचति' इतिवद् सामान्यविशेषभावेन सहप्रयोगः ॥ आत्वजातेर्भिन्नकालावर्णवृत्तित्वाभावाद् द्वितीयमाश्रयति—**व्यक्तिरिति** ॥ यद्गुणस्येत्यादिर्यद्गुणाद्धिः ॥

(कारणजिज्ञासाभाष्यम्)

किं च कारणं न स्यात् ?

(प्रदीपः) **किं च कारणमिति** । अभेदका गुणाः, मुण्डेन हि कृते चौर्ये कुन्तलित्वावस्थायामपि चौरोऽयमिति व्यपदिश्यत एवेति प्रश्नः ॥

(उद्द्योतः) भाष्ये—किं च कारणमिति । निमित्तकारणहेतुष्विति हेतौ प्रथमा ॥

(कारणप्रदर्शकैकदेशिभाष्यवार्तिकम्)

॥ भेदकत्वात्स्वरस्य ॥ * ॥

(भाष्यम्)

भेदका उदात्तादयः ।

कथं पुनर्ज्ञायते—भेदका उदात्तादय इति ?

एवं हि दृश्यते लोके—य उदात्ते कर्तव्येऽनुदात्तं करोति खण्डिकोपाध्यायस्तस्मै चपेटां ददाति —अन्यत् त्वं करोषीति ॥

(भाष्यम्)

अस्ति प्रयोजनमेतत् ।

किं तर्हि ?

इति—

(उद्द्योतः) अस्ति प्रयोजनमेतदिति काका सूचितमाशयं पृच्छति—किं तर्हीति । किं तर्हि-इति प्रश्ने इति-इदं वक्तव्यमित्यर्थः ॥

(कारणप्रदर्शकन्यासान्तरभाष्यम्)

भेदकत्वाद्गुणस्येति वक्तव्यम् ।

किं प्रयोजनम् ?

आनुनासिक्यं नाम गुणः, तद्भिन्नस्यापि ग्रहणं यथा स्यात् ।

किं च कारणं न स्यात् ?

'भेदकत्वाद्गुणस्य' । भेदका गुणाः ॥

कथं पुनर्ज्ञायते—भेदका गुणा इति ?

एवं हि दृश्यते लोके—एकोऽयमात्मा—उदकं नाम, तस्य गुणभेदादन्यत्वं भवति—अन्यदिदं शीतम्, अन्यदिदमुष्णमिति ॥

(प्रदीपः) **भेदकत्वादिति** । सर्वगुणसंग्रहार्थं गुणग्रहणं कर्तव्यमित्यर्थः ॥ **एकोऽयमिति** । उदकत्वजातियोगादत्रैकत्वं न विवक्षितं । किं तर्हि ? विशिष्टभाजनस्थमेकमुदकद्रव्यम्, तदेव च गुणान्तरयोगादन्यत्वेन लोके व्यपदिश्यते ॥

(उद्द्योतः) तदाह—**भेदकत्वादित्यादि** ॥ जात्यात्मनैकत्वे व्यक्तिभेदादेवोपपत्तेर्न गुणभेदकृतभेदे एतमुदाहरणं स्यादत आह—**उदकत्वेति** । आत्मशब्दो द्रव्यवाची भाष्ये ॥

(अभेदकत्वाक्षेपसिद्धान्तिभाष्यम्)

ननु च भोः—अभेदका अपि गुणा दृश्यन्ते । तद्यथा—देवदत्तो मुण्ड्यपि जट्यपि शिख्यपि स्वामाख्यां न जहाति । तथा-बालो युवा वृद्धः, वत्सो दम्यो बलीवर्द इति ॥

(उद्द्योतः) बालो युवा-इति भाष्ये स्वामाख्यां न जहातीत्यनुकर्षः । एतेनाभेदकत्वे प्रत्यभिज्ञा प्रमाणं दर्शितम् ॥

(आक्षेपभाष्यम्)

उभयमिदं गुणेषूक्तम्—भेदकाः—अभेदकाः इति

किं पुनरत्र न्याय्यम् ?

(प्रदीपः) **उभयमिति** । आम्नायशब्दा नियतस्वरा इति वेदे गुणानां भेदकत्वम् । लोके तूभयथा व्यवहारः—गोपिण्डो वत्साद्यवस्थाभेदात् क्रयविक्रयादिषु मूल्यादिभेदाद्भेदेन व्यवह्रियते, स एवायमिति प्रत्यभिज्ञानादभेदेनापि ॥ इति प्रश्नः—**किं पुनरिति** ॥ **अत्रेति** । शास्त्रे ॥

(उद्द्योतः) ननु गुणेषूभयाङ्गीकारे खण्डिकोपाध्यायचपेटादानं विरुध्येतेति चेन्न, यतः 'उभयं' इति लोकमात्रविषयमिति न विरोध इत्याह—**आम्नायेति** ॥ ननूभयोरपि न्याय्यत्वप्रतिपादनेन किं पुनरत्र न्याय्यमिति प्रश्नोऽयुक्तोऽत आह—**शास्त्रे इति** । 'अत्र' इति निर्धारणसप्तमी नेति भावः ॥

(सिद्धान्तसमाधानभाष्यम्)

अभेदका गुणा इत्येव न्याय्यम् ।

कुत एतत् ?

यदयम्—"अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः" इति उदात्तग्रहणं करोति । यदि भेदका गुणाः स्युः, उदात्तमेवोच्चारयेत् ॥

(प्रदीपः) **उदात्तमेवेति** । तस्माद्गुणरहितस्योच्चारणा-

भावान्नान्तरीयकत्वादुच्चार्यमाणोऽपि गुणः प्रयत्नमन्तरेण न विवक्षित इत्यर्थः ॥ यद्येवं कथमन्यत्रोक्तं—'**उदात्तनिपातनं करिष्यते**' इति, यावता तत्राप्यविवक्षा प्राप्नोति । नैष दोषः; तत्रापि हि '**स्थानेऽन्तरतमः**' इति वचनादादेशस्य यः स्वरः प्राप्तस्तस्मिन्नुच्चारयितव्य उदात्तोच्चारणं प्रयत्नेन विवक्षार्थं विधीयते । एवमनुनासिकस्य प्रयत्नाधिक्येनोच्चारणं विवक्षार्थमेव, '**उञः**' '**ऊँ**' इति यथा ॥ **अन्ये त्वाहुः**-एकश्रुत्या सूत्राणि पठ्यन्त इति क्वचिदुदात्तोच्चारणं तद्विवक्षार्थमिति ॥

(उद्योतः) (भाष्ये) इत्येव **न्याय्यमिति** । विधेयाण्-भिन्नविषये इति शेषः । तत्रैतत्कृतस्यापि **अप्रत्यय** इति निषेधात् । अतस्तथैव ज्ञापकमुपन्यस्यति (भाष्ये)—**यदयमिति** ॥ **प्रयत्नं**—स्वशब्देनोपादानरूपम् ॥ **कथमिति** । यथा वध्यादेशे उदात्तनिपातनेन **एकाच** इति सूत्रस्थमेकाज्ग्रहणं न कार्यमिति ॥ **यः स्वरः प्राप्त इति** । हन्तेरनुदात्तत्वादनुदात्त इत्यर्थः । **न चैवमस्थ्यादीना**-माद्युदात्तत्वेनादेशानङः स्थान्यनुरूपेऽनुदात्ते उच्चारणीये उदात्तोच्चारणं विवक्षार्थमिति ज्ञापितेऽपि व्यर्थमुदात्तग्रहणमिति **वाच्यम्** । परमास्थिशब्दादावन्तोदात्ते उदात्तगुणकस्यापि स्थानित्वेन विवक्षायां मानाभावादित्याशयात् ॥ नन्वेवमपि चतसर्याद्युदात्तनिपातनसामर्थ्यात् '**चतस्रः**' इत्यत्र **चतुरः शसी**त्यस्याप्रवृत्तिरिति भाष्योक्तमनुपपन्नम् । चतुःशब्दस्य **त्रः संख्याया** इत्याद्युदात्ततया तत्स्थानिकचतसरि स्थानिस्वरेणाद्युदात्तोच्चारणोपपत्त्या **चतुरः शसी**त्येतद्बाधकत्वायोगादत आह—**अन्ये त्विति** । एकश्रुतिश्च **विभाषा छन्दसी**ति वैकल्पिकी, तत्पाठे क्वचिदुदात्तोच्चारणं विवक्षार्थम् । त्रैस्वर्येण पाठमभिप्रेत्य तु प्रकृतसूत्रस्थं ज्ञापकमित्यविरोधः ॥ '**अन्ये तु**' इत्यरुचिबीजं तु निपातनं नामान्यादृशे प्रयोगे प्राप्तेऽन्यादृशप्रयोगकरणं, तद्रूपाधानात् तत्र तत्रोदात्तादिविवक्षा । तिसृचतसृ इत्यत्रापि द्वन्द्वप्रयुक्तान्तोदात्ते उच्चारणीये आद्युदात्तोच्चारणं विवक्षार्थम् । संपूर्णाष्टाध्यायी आचार्येणैकश्रुत्या पठितेत्यत्र न मानम् । क्वचित्कस्यचित्पदस्यैकश्रुत्या पाठः, यथा **दाण्डिनायनादि**सूत्रे—ऐक्ष्वाकेति । एतावदेव भाष्याल्लभ्यते ॥ यद्यप्यध्येतार एकश्रुत्यैवाङ्गानि पठन्ति ब्राह्मणवत्, तथापि व्याख्यानतोऽनुनासिकत्वादिवदुदात्तनिपातनादिज्ञानमित्याहुः ॥

(आक्षेपभाष्यम्)

यदि तर्हि भेदका गुणाः, अनुदात्तादेरन्तोदात्ताच्च यदुच्यते तत्स्वरितादेः स्वरितान्ताच्च प्राप्नोति ॥

(प्रदीपः) **अनुदात्तादेरिति** । अजुपलक्षणार्थोऽनुदात्तश्रुतिः स्यादिति प्रश्नः ॥

(उद्योतः) **स्वरितादेरिति**—भाष्ये—उपलक्षणम्, उदात्तादेरन्तानुदात्ताच्च प्राप्नोतीत्यपि बोध्यम् ॥

(समाधानभाष्यम्)

नैष दोषः । आश्रीयमाणो गुणो भेदको भवति । तद्यथा—'शुक्लमालभेत' 'कृष्णमालभेत' । तत्र यः शुक्ल आलब्धव्ये कृष्णमालभते, न हि तेन यथोक्तं कृतं भवति ॥

(प्रदीपः) उत्तरे त्वजग्रहणमेव कुर्यादित्यभिप्रायः ॥

(उद्योतः) **आश्रीयमाण इति** । शब्देन निपातनेन वाऽऽश्रीयमाण इत्यर्थः ॥ नन्वेवमनुदात्तादिग्रहणं व्यर्थं स्यादत आह—**अजिति** ॥

(एकदेशिसमाधानभाष्यम्)

असंदेहार्थस्तर्हि तकारः । ऐजित्युच्यमाने संदेहः स्यात्—किमिमावैचावेव, आहोस्विदाकारोऽप्यत्र निर्दिश्यते ?

(समाधानबाधकभाष्यम्)

संदेहमात्रमेतद्भवति । सर्वसंदेहेषु चेदमुपतिष्ठते-'व्याख्यानतो विशेषप्रतिपत्तिर्न हि संदेहादलक्षणम्' इति । त्रयाणां ग्रहणमिति व्याख्यास्यामः । अन्यत्रापि ह्ययमेवंजातीयकेषु संदेहेषु न कंचिद्यत्नं करोति । तद्यथा-"औतोम्शसोः" इति ॥

(प्रदीपः) **व्याख्यानत इति** । '**प्रस्थेऽवृद्धं**-'इत्याद्युदात्तत्वे सिद्धे '**मालादीनां च**' इति मालाशब्दस्य वृद्धार्थत्वादुपादानस्याकारप्रश्लेषनिश्चय इत्यर्थः ॥

(सिद्धान्तिसमाधानभाष्यम्)

इदं तर्हि प्रयोजनम्—आन्तर्यतस्त्रिमात्रचतुर्मात्राणां स्थानिनां त्रिमात्रचतुर्मात्रा आदेशा मा भूवन्निति । खट्वा इन्द्रः-खट्वेन्द्रः, खट्वा उदकं-खट्वोदकम्, खट्वा ईषा-खट्वेषा, खट्वा ऊढा-खट्वोढा, खट्वा एलका-खट्वैलका, खट्वा ओदनः-खट्वौदनः, खट्वा ऐतिकायनः-खट्वैतिकायनः, खट्वा औपगवः-खट्वौपगव इति ॥

(प्रदीपः) **इदं तर्हीति** । ननु भाव्यमानत्वादादैचो ग्राहका न भविष्यन्ति । नैतदस्ति । न ह्यत्र संज्ञाविधावादैचो भाव्यन्ते । किन्तु ऐज्भिरण्त्वात्त्रिमात्रचतुर्मात्राणां ग्रहणात्संज्ञाप्रसङ्गात् वृद्धिगुणविधौ तेषामपि प्रसङ्गात्तन्निषेधाय तपरत्वम् ॥

(उद्योतः) ऐज्ग्रहणार्थं तपरत्वमित्याह—**इदं तर्हीति**-भाष्ये । चतुर्मात्रोऽपि प्लुतः **प्लुतावैच** इति सूत्रे भाष्ये स्पष्टः ॥ कार्यकालमाश्रित्य नोदयति—**नन्विति** । अयं भावः—तत्पक्षे **मृजेर्वृद्धि**-रित्यादावुपस्थितं **वृद्धिरादैजि**ति पदैकवाक्यतयाऽन्वेति । एकं वृद्धिपदं तु प्रत्यभिज्ञामात्रफलकमनुवाद एव । एवं च भाव्यमानत्वं स्पष्टमेवेति ॥ उत्तरस्य त्वय भावः—अनुवादत्वकल्पनापेक्षया तत्रोपस्थित **वृद्धिरादैजि**ति तत्रैव शक्तिग्रहं सपाद्य वाक्यभेदेन **मृजेर्वृद्धि**-रित्यस्यार्थं बोधयति । **ज्योतिष्टोमेन यजेते**त्यादौ तु शक्तिग्राहकशास्त्रान्तराभावादगत्या विधावेव सामानाधिकरण्यान्नामधेयत्वावगतिः कल्प्यते । न तु विद्यमाने शक्तिग्राहके तथाकल्पनमुचितं पदस्यानुवादकत्वकल्पनं चेति ॥ यैस्तु—कार्यकालपक्षे **वृद्धिरादै**जित्यादेर्यत्र वृद्धिपदं तत्रादैजित्युपतिष्ठत इत्यर्थः । यथा च ज्योतिष्टोमादिपदानां यागविधावेव सामानाधिकरण्यान्नामधेयत्वावगतिस्तथेहापि **मृजेर्वृद्धि**-रित्यादौ सामानाधिकरण्यान्नामधेयत्वावगतिः । उपस्थापकेन वृद्ध्यादिपदेन उपस्थाप्यस्य वृद्ध्या बोधनात्परं संज्ञासूत्रत्वावगतिरिति । तन्न, **कार्यकालं संज्ञापरिभाषं** मस्येत्युपस्थितमिदं भवति—'यचि

भम्' इतीसि ष्यङः संप्रसारणमिति सूत्रस्थभाष्येण, कार्यकालं संज्ञापरिभाषं प्रगृह्यः प्रकृत्येत्युपस्थितमिदं भवति—'ईदूदेद्द्विवचनं प्रगृह्यं' इति ईदूदेदिति सूत्रस्थभाष्येण च विरोधात्। त्वदीत्या ह्युपस्थितमिदं भवति यचीतीत्येव वक्तव्यं स्यात्। अथ संज्ञेत्यादिप्रकृतसूत्रस्थवार्तिकविरोधश्च । प्रकारान्तरेणाप्रत्यतत्प्रत्याख्यानपरभाष्यविरोधश्च । किंच मृजेर्वृद्धिरित्यादिसूत्रस्थवृद्ध्यादिपदानां तदुपस्थितिसंपत्त्या चारितार्थ्येन स्वोपस्थापितपदार्थेऽन्वये मानाभावात् तत्रैवपरिभाषाऽनुपस्थित्यापत्तिः, वृद्धिपदेनाविधानात् ॥ मृजेर्वृद्धिरित्यादौ एकपदोपस्थापकस्यापि विधेयाकाङ्क्षासत्त्वाद् विधिविषये एव तत्प्रवृत्तेश्च भवत्येवान्वयः । एवं च ज्योतिष्टोमवाक्यादैलक्षण्येनात्र नामधेयता दुरुपपादा । किं चोपस्थाप्यार्थस्य वृत्त्या बोधनात्संज्ञासूत्रत्वं वा, इको गुणेत्यादिवदुपस्थापकत्वात्परिभाषात्वं वेत्यत्र विनिगमकाभावः ॥ वृद्ध्यादिपदैर्वृत्त्या बोधनं च दुरुपपादम्। अनुवादेऽपि संज्ञासूत्रोपस्थितिरणोऽप्रगृह्यस्य वृद्धिर्यस्येत्यादिविषये भाष्ये स्पष्टेति दिक् ॥

(आक्षेपभाष्यम्)

अथ क्रियमाणेऽपि तकारे कस्मादेव त्रिमात्रचतुर्मात्राणां स्थानिनां त्रिमात्रचतुर्मात्रा आदेशा न भवन्ति ?

(समाधानभाष्यम्)

"तपरस्तत्कालस्य" इति नियमात् ॥

(समाधानबाधकभाष्यम्)

ननु तः परो यस्मात्सोऽयं तपरः ॥

(समाधानसाधकभाष्यम्)

नेत्याह । तादपि परस्तपरः ॥

(इष्टानुपपत्तिसाधकभाष्यम्)

यदि तादपि परस्तपरः "ऋदोरप्" इतीहैव स्यात्—यवः, स्तवः । लवः, पव इत्यत्र न स्यात् ॥

(अनुपपत्तिबाधकभाष्यम्)

नैष तकारः ।

कस्तर्हि ?

दकारः ॥

(आक्षेपभाष्यम्)

किं दकारे प्रयोजनम् ?

(प्रतिबन्द्या समाधानभाष्यम्)

अथ किं तकारे ? यद्यसंदेहार्थस्तकारः, दकारोऽपि । अथ मुखसुखार्थस्तकारः, दकारोऽपि । वृद्धिरादैच् ॥ १ ॥

(प्रदीपः) एवं स्थिते चोदयन्ति—यद्यैजर्थस्तकारस्तेनाकारस्य संबन्धाभावात् कथं 'आत्' इत्येतत्पदमुच्यते । तात्पर्येणैजर्थत्वं तकारस्योच्यते, आनुषङ्गिकं त्वाकारार्थत्वं । ज्ञापकद्वारेण आकारप्रश्लेषे विज्ञायमाने प्रतिपत्तिगौरवं भवति । सति तु तकार आकारस्वरूपप्रतिपत्तिः स्पष्टा भवतीति तकारसहितस्याकारस्यैच्विधानुकार्यप्रतिपादनार्थत्वाद्विभक्त्युत्पत्तौ सत्यां 'आत्' इत्येतत्पदं सिद्धम् ॥ १ ॥

(उद्योतः) भाष्ये किं तकारे' इत्यस्य तादपि परस्तपर इत्यनभ्युपगमेऽपि इति शेषः ॥ संज्ञाभावादिति । लोपशेषेऽपि भाषाभावादित्यर्थः । सान्तस्य पदत्वाभावे जश्त्वं न स्यादिति भावः ॥ आनुषङ्गिकं फलं दर्शयति—ज्ञापकद्वारेणेति ॥ १ ॥

(२ परिभाषासूत्रम् १ । १ । २ । आ. ३ ॥)

इको गुणवृद्धी ॥ १ । १ । ३ ॥

(सूत्रप्रयोजनाधिकरणम्)

(आक्षेपभाष्यम्)

इग्ग्रहणं किमर्थम् ?

(प्रदीपः) **इको गुणवृद्धी** ॥ ३ ॥ **इग्ग्रहणमिति ।** वक्ष्यमाणज्ञापकवशादाकारादिनिरासादिक एव गुणवृद्धी भविष्यत इति प्रश्नः ॥

(उद्योतः) इको गुण० ॥ ३ ॥ गुणवृद्धिग्रहणस्योत्तरत्र निषेध्यसमर्पणायावश्यकत्वेऽपि एकपदस्येकः स्थान इत्यर्थार्थमावश्यकत्वेऽपि योगविभागविषयकोऽयं प्रश्नो भाष्ये—इग्ग्रहणमिति ॥

(७४ समाधानवार्तिकम् ॥ १ ॥)

॥ * ॥ इग्ग्रहणमात्सन्ध्यक्षरव्यञ्जननिवृत्त्यर्थम् ॥ * ॥

(भाष्यम्)

इग्ग्रहणं क्रियते ।

किं प्रयोजनम् ?

आकारनिवृत्त्यर्थं सन्ध्यक्षरनिवृत्त्यर्थं व्यञ्जननिवृत्त्यर्थं च ॥

(प्रदीपः) **आत्सन्ध्यक्षरेति ।** आकारादीनां स्थानित्वस्य निवृत्त्यर्थमित्यर्थः ॥

(उद्योतः) ननु इक्ग्रहणेनाकारादीनां निवृत्तिरशक्या कर्तुमत आह—**स्थानित्वस्येति** ॥

(प्रथमप्रयोजनोपपादनभाष्यम्)

आकारनिवृत्त्यर्थं तावत्—याता, वाता । आकारस्य गुणः प्राप्नोति । इग्ग्रहणान्न भवति ॥

(प्रदीपः) आकारस्यान्त्यस्य वृद्धिविधावभावाद्विशेषाभावादकारस्य च **'अतो लोपः'** इति लोपविधानादाकारस्य गुणप्रसङ्गमुदाहरति—**यातेति** ॥

(उद्योतः) ननु आकारस्य वृद्ध्युदाहरणादाने गुणांशे च अकारोदाहरणादाने किं बीजमत आह—**आकारस्येति । वृद्धिविधौ**=सिचिवृद्धिविधौ । अयासीदित्यादौ अपवादत्वात्सगिड्भ्यां सा बाध्यते इति भावः ॥ इतरवृद्धिविधौ संभवेऽप्याह—**विशेषाभावादिति ॥ अकारस्येति ।** व्यङ्लोपावितिपूर्वविप्रतिषेधेनातो लोपस्य

वृद्धिगुणबाधकत्वादिति भावः ॥ पुन्नीयतीत्यादौ त्वविशेष इति बोध्यम् ॥ आकारस्य गुणः—सार्वधातुकार्धधातुकयोरित्यनेन ॥

(द्वितीयप्रयोजनोपपादनभाष्यम्)

सन्ध्यक्षरनिवृत्त्यर्थम्—ग्लायति, म्लायति । सन्ध्यक्षरस्य गुणः प्राप्नोति । इग्ग्रहणान्न भवति ॥

(प्रदीपः) ग्लायतीति । एचां द्विमात्रत्वाविशेषात् प्रयत्नाधिक्याभावादैकारोपदेशेऽप्यैकारो गुणः स्यात् ॥

(उद्द्योतः) ननु चैकारोच्चारणसामर्थ्यात् गुणो नेत्यत आह—एचामिति । सर्वेषां विवृत एव प्रयत्न इत्यभिमानः ॥

(तृतीयप्रयोजनोपपादनभाष्यम्)

व्यञ्जननिवृत्त्यर्थम्—उम्भिता, उम्भितुम्, उम्भितव्यम् । व्यञ्जनस्य गुणः प्राप्नोति । इग्ग्रहणान्न भवति ॥

(प्रदीपः) उम्भितेति । भकारस्यौष्ठ्यत्वादोकारो गुणः स्यात् ॥

(प्रथमप्रयोजननिराकरणभाष्यम्)

आकारनिवृत्त्यर्थेन तावन्नार्थः । आचार्यप्रवृत्तिर्ज्ञापयति—नाकारस्य गुणो भवतीति । यदयम् "आतोऽनुपसर्गे कः" (३।२।३) इति ककारमनुबन्धं करोति ॥

कथं कृत्वा ज्ञापकम् ?

कित्करण एतत्प्रयोजनम्—कितीत्याकारलोपो यथा स्यात् । यदि चाकारस्य गुणः स्यात्, कित्करणमनर्थकं स्यात् । गुणे कृते द्वयोरकारयोः पररूपेण सिद्धं रूपं स्यात्—गोदः, कम्बलद इति । पश्यति त्वाचार्यः—नाकारस्य गुणो भवतीति, ततः ककारमनुबन्धं करोति ॥

(प्रदीपः) पररूपेणेति । अतो लोपस्तु न भवति, आर्धधातुकोपदेशे यदकारान्तं तस्य लोपविधानात् ॥

(उद्द्योतः) आर्धधातुकोपदेश इति । गुणनिष्पन्नश्च तदुत्तरकालिक इति भावः ॥

(द्वितीयप्रयोजननिराकरणभाष्यम्)

सन्ध्यक्षरनिवृत्त्यर्थेनापि नार्थः । उपदेशसामर्थ्यात्सन्ध्यक्षरस्य गुणो न भविष्यति ॥

(प्रदीपः) उपदेशसामर्थ्यादिति । प्रतिपत्तिलाघवार्थमेकारमेवोपदिशेदित्यर्थः ॥

(उद्द्योतः) पतिपत्तिलाघवम्–प्रक्रियालाघवम् । "तेभ्योऽपि विवृतावेङौ ताभ्यामैचौ तथैव च ॥" इति पाणिनीयशिक्षोक्तेः प्रयत्नलाघवमपि बोध्यम् ॥

(तृतीयप्रयोजननिराकरणभाष्यम्)

व्यञ्जननिवृत्त्यर्थेनापि नार्थः । आचार्यप्रवृत्तिर्ज्ञापयति-न व्यञ्जनस्य गुणो भवतीति । यदयं जनेर्डं शास्ति ॥

कथं कृत्वा ज्ञापकम् ?

डित्करण एतत्प्रयोजनम्-डितीति टिलोपो यथा स्यात् । यदि व्यञ्जनस्य गुणः स्यात्, डित्करणमनर्थकं स्यात् । गुणे कृते त्रयाणामकाराणां पररूपेण सिद्धं रूपं स्यात्-उपसरजो मन्दुरज इति । पश्यति त्वाचार्यः-न व्यञ्जनस्य गुणो भवतीति । ततो जनेर्डं शास्ति ॥

(प्रदीपः) यदयं जनेरिति । यद्येवं मिदेर्गुणो विधीयमानो ज्ञापकेन व्यञ्जनस्य निरस्तत्वादिग्ग्रहणाभावाच्च सर्वादेशः प्राप्नोति । मिद इः-मिदिः-इत्याश्रयणादिकारस्यैव भविष्यतीत्यदोषः ॥

(उद्द्योतः) इग्ग्रहणेति । ततश्च मिदेरिति नावयवषष्ठी, किंतु स्थानषष्ठीति सर्वादेशो गुणः स्यादित्यर्थः ॥

(प्रथमप्रयोजनबाधकज्ञापकनिराकरणभाष्यम्)

नैतानि सन्ति ज्ञापकानि । यत्तावदुच्यते—कित्करणं ज्ञापकं-आकारस्य गुणो न भवतीति ॥

उत्तरार्थमेतत्स्यात्—"तुन्दशोकयोः परिमृजापनुदोः" (३।२।५) इति ॥

(प्रदीपः) यत्तावदिति । विशेषप्रतिपादनाय सकलज्ञापकाक्षेपः ॥

(उद्द्योतः) भाष्ये—नैतानि सन्ति ज्ञापकानीति । छत्रिन्यायेन ॥ ननु नैतानि सन्ति ज्ञापकानीति प्रतिज्ञायाम्रे ज्ञापकसमर्थनमयुक्तमित्यत आह—विशेषेति । 'टकः कित्वं ज्ञापकम् । थं विधिं प्रति' इत्यादिविशेषप्रतिपादनायेत्यर्थः ॥

(प्रथमप्रयोजनबाधकज्ञापकान्तरभाष्यम्)

यत्तर्हि "गापोष्टक्" (३।२।८) इत्यनन्यार्थं ककारमनुबन्धं करोति ॥

(प्रदीपः) केचिदाहुः—टकः कित्वेन ज्ञापकेनाकारनिवृत्त्यर्थत्वे निराकृते 'यदप्युच्यते' इति ज्ञापकाक्षेपो ग्रन्थच्छायां न पुष्णाति, तस्मादार्थेन क्रमेण सर्वज्ञापकभङ्गोपन्यासं कृत्वा यथासंभवं ज्ञापकसमर्थनं कर्तव्यम् ॥

(उद्द्योतः) शङ्कते—केचिदिति । 'यदप्युच्यते' इति समुच्चयार्थापिशब्देनेति शेषः ॥ आर्थेन=सामर्थ्यप्राप्तेन ॥ भङ्गेति । भङ्गसदृश इति भावः ॥

(द्वितीयप्रयोजनबाधकसामर्थ्यदूषकभाष्यम्)

यदप्युच्यते-उपदेशसामर्थ्यात्संध्यक्षरस्य गुणो न भवतीति ॥ यदि—यद्यत्संध्यक्षरस्य प्राप्नोति, तत्तदुपदेशसामर्थ्याद्बाध्यते, आयादयोऽपि तर्हि न प्राप्नुवन्ति ॥

(प्रदीपः) आयादयोऽपीति । ऐकारोच्चारणस्याविकृतरूपश्रवणार्थत्वादिति भावः ॥

(सामर्थ्यदूषणनिराकरणभाष्यम्)

नैष दोषः । यं विधिं प्रत्युपदेशोऽनर्थकः स विधिर्बाध्यते । यस्य तु विधेर्निमित्तमेव नासौ बाध्यते । गुणं च प्रत्युपदेशोऽनर्थकः, आयादीनां पुनर्निमित्तमेव ॥

(प्रदीपः) यं विधिमिति । आयादेशस्यैकार एव निमित्तमित्यायादेशो न बाध्यते । न हि ग्लायिस्येवं पाठः शक्यः कर्तुम्, तथा ग्लायत इत्यादिरूपासिद्धिप्रसङ्गात् । न ध्याख्येति निपातनादात्वं गुणवन्न बाधिष्यते ॥

(उद्द्योतः) ग्लायत इति । आदिना जग्लाविलादि ॥ नन्वेवमात्वमपि बाध्येत । न हि तस्य पेकारो निमित्तं, 'ग्ले' इति पाठेऽपि सुकरत्वादत आह—न ध्याख्येति । 'ध्या' इति कृतात्वनिर्देशेनैकारोच्चारणस्याबाधकत्वज्ञापनादिति भावः ॥ न चास्य सौत्रत्वम् । बाधकत्वमङ्गीकृत्य सौत्रत्वकल्पनापेक्षयाऽबाधकत्वज्ञापनस्य लघुत्वादित्याहुः ॥ न च रैशब्दादिभ्य आचारक्विपि रायतीत्यादौ सन्ध्यक्षरस्य गुणः स्यादिति वाच्यम् । एजन्तेभ्य आचारक्विबभाव एतद्भाष्यप्रामाण्यात्—इत्यदोषात् ॥ गुणवदिति । वैधर्म्ये दृष्टान्तः ॥

(तृतीयप्रयोजनबाधकज्ञापकनिराकरणभाष्यम्)

यदप्युच्यते—जनेर्डवचनं ज्ञापकम्—न व्यञ्जनस्य गुणो भवतीति ॥ सिद्धे विधिरारभ्यमाणो ज्ञापकार्थो भवति । न च जनेर्गुणेन सिद्ध्यति । कुतो ह्येतत्-जनेर्गुण उच्यमानोऽकारो भवति, न पुनरेकारो वा स्यादोकारो वेति ?

(ज्ञापकसाधकभाष्यम्)

आन्तर्यतोऽर्धमात्रिकस्य व्यञ्जनस्य मात्रिकोऽकारो भविष्यति ॥

(ज्ञापकबाधकभाष्यम्)

एवमप्यनुनासिकः प्राप्नोति ॥

(ज्ञापकसाधकभाष्यम्)

पररूपेण शुद्धो भविष्यति ॥

(प्रदीपः) पररूपेणेति । रूपग्रहणस्येदमेव प्रयोजनम्—यादृक् परस्य रूपं तादृगेव यथा स्यादिति ॥

(उद्द्योतः) ननु पररूपेऽपि गुणानामभेदकतया कदाचित्सानुनासिकोऽपि स्यादत आह—रूपग्रहणस्येति ॥ परे तु अत्र पररूपशब्देन परशब्देन वा यदुपस्थितं रूपं प्रयोगस्थं तस्य ग्रहणम्, स्थाने जायमानः किंगुणक इत्याकाङ्क्षायामन्तरतमपरिभाषयोभयगुणकः । प्रकृते चोभयान्तरतमासंभवात् परशब्देन यद्गुणस्योपस्थितिस्तद्गुणक एव भविष्यतीति भाष्याशयात् 'रूपग्रहणस्य'इत्यादि चिन्त्यम् । गुणानां शब्दत्वादिवत् शब्दरूपत्वाभावेन व्यावृत्त्यसंभवश्च रूपग्रहणेनेत्याहुः ॥

(ज्ञापकबाधकभाष्यम्)

एवं तर्हि गमेरप्ययं डो वक्तव्यः । गमेश्च गुण उच्यमान आन्तर्यत ओकारः प्राप्नोति ॥ तस्मादिद्ग्रहणं कर्तव्यम् ॥

(प्रदीपः) गमेरप्ययमिति । सप्तम्यां जनेर्डः (३।२।९७) इत्यतोऽन्येष्वपि दृश्यते (१०१) इत्यत्र डोऽनुवर्तमानो गमेरपि विधीयत इत्यज्ञापकं डित्त्वमिति व्यञ्जननिवृत्त्यर्थं सूत्रं स्थितम् ॥

(उद्द्योतः) ननु गमेरप्ययं ड इति भाष्यमनुपपन्नं, गमः 'गमश्च अन्तात्यन्ताध्वदूरपार-' इति सूत्रे पठितेनान्यत्रापि दृश्यत इति वार्तिकेन 'नगः-अगः' इत्यादौ डस्य सत्त्वादत आह—सप्तम्यामिति । सप्तम्यां जनेरित्युत्तरं पठितेऽन्येष्वपि दृश्यत इति सूत्रे दृशिग्रहणस्य सर्वोपाधिव्यभिचारार्थत्वेन तेनैव प्रकृत्यन्तरादपि डे सिद्धेऽन्तात्यन्तेति प्रकरणस्थं वार्तिकं न कार्यमिति भावः ॥ भाष्ये—आन्तर्यत ओकार इति । स्थानत आन्तर्यादिति भावः ॥ ननु सनोतेरडः सम्बद्धेति डित्करणान्न व्यञ्जनस्य गुण इति चेन्न । उणादीनामव्युत्पत्तिपक्षाङ्गीकारात् ॥ न चैवमपि स्थानप्रयत्नान्तरतमेषु हकारादिषु चरितार्थानि गुणादिशास्त्राणि व्यञ्जने न प्रवर्तेन्न इति वाच्यम् । ईशादौ शकारे तथाप्यतिप्रसङ्गात् । सम्मते स्थानप्रयत्नैक्यादिति भाष्याशयः । 'स्थानेऽन्तरतमे' इति सप्तम्यन्तपाठस्य भाष्ये प्रत्याख्यानेनास्या युक्तेरसंभवदुक्तिकत्वाच्च ॥

(इति सूत्रप्रयोजननिरूपणाधिकरणम् ॥)

(अथ गुणवृद्धिशब्दानुवृत्त्यधिकरणम्)

(आक्षेपभाष्यम्)

यदीग्ग्रहणं क्रियते, द्यौः-पन्थाः-सः-इममिति, एतेऽपीकः प्राप्नुवन्ति ॥

(उद्द्योतः) भाष्ये—एतेऽपीति । औकारादयः ॥ यथूदाहरणेष्विकः प्राप्नुवन्तीत्यन्वयः ॥ 'सः' इत्यत्र तु न स्यादेवेति भावः ॥ त्यदादीनाम इत्यत्र त्यदादीनामिति तु सदोः सः स्यादित्युत्तरार्थं स्यात्, संयोगसंज्ञकव्यावृत्त्यर्थं च स्यादिति बोध्यम् ॥

(७५ सिद्धान्तसमाधानवार्तिकम् ॥ १ ॥)

॥ * ॥ संज्ञया विधाने नियमः ॥ * ॥

(भाष्यम्)

संज्ञया ये विधीयन्ते तेषु नियमः ॥

(प्रदीपः) संज्ञयेति । गुणवृद्ध्यनुवृत्त्यैव गुणवृद्ध्योरिकः सिद्धत्वाद् द्वितीयं गुणवृद्धिग्रहणमाश्रितगुणवृद्धिशब्दव्यापारार्थं विज्ञायते । तेन गुण इत्येवं यो गुणः, वृद्धिरित्येवं या वृद्धिरिति विज्ञायते । अथवा गुणवृद्धिमात्रग्रहणे गुणवृद्ध्यधिकारादेव सिद्धे पुनर्गुणवृद्धिग्रहणं गुणवृद्धिशब्दव्यापाराश्रयणार्थं विज्ञायते ॥

(उद्द्योतः) आश्रितेति । आश्रितो गुणवृद्धिशब्दव्यापारः=उच्चारणं येषु आदेशेषु विधीयमानेषु तदर्थमित्यर्थः ॥ तेनेति । 'इत्येवं' इत्यध्याहृत्य स्वरूपपदार्थकेनान्यतरेण विशेषणादीदृशार्थलाभ इति भावः ॥ अत एव संबन्धानुवृत्तिप्रदर्शनपरभाष्ये गुणवृद्धी इत्युच्चार्य गुणवृद्धिग्रहणमनुवर्तत इति उक्तम् ॥ उपक्रमस्थगुणवृद्धिग्रहण

सामर्थ्यमित्येतद्भाष्यस्वारस्यादाह— अथवेति । पुनरुपादानसामर्थ्यादित्यर्थः गुणवृद्धिग्रहणं गुणवृद्धिशब्दविहितगुणवृद्धिलाक्षणिकमिति भावः ॥

(आक्षेपभाष्यम्)

किं वक्तव्यमेतत् ?

(समाधानभाष्यम्)

न हि,

कथमनुच्यमानं गंस्यते ?

गुणवृद्धिग्रहणसामर्थ्यात् ॥

(सामर्थ्याक्षेपभाष्यम्)

कथं पुनरन्तरेण गुणवृद्धिग्रहणमिको गुणवृद्धी स्याताम् ?

(समाधानभाष्यम्)

प्रकृतं गुणवृद्धिग्रहणमनुवर्तते ॥

क्व प्रकृतम् ?

"वृद्धिरादैच्-अदेङ्गुणः" इति ॥

(आक्षेपभाष्यम्)

यदि तदनुवर्तते, 'अदेङ्गुणो वृद्धिश्च' इत्यदेङां वृद्धिसंज्ञाऽपि प्राप्नोति ॥

(प्रदीपः) अदेङामिति । पूर्वसूत्रे संज्ञिसंबन्धायोपात्तो यादृशो वृद्धिशब्दस्तादृश एवोत्तरत्रानुवर्तत इति 'अदेङां' इत्युक्तम् । तेनेदत्र चोदनीयम्—वृद्धिशब्दोऽनुवर्तमान आदैचः प्रत्याययतीत्यादैचां गुणसंज्ञा प्राप्नोति—इति ॥

(उद्द्योतः) यादृश इति । स्वरूपपदार्थक इत्यर्थः ॥ नन्वेवं सति उत्तरत्र निषेध्यसमर्पणार्थं गुणवृद्धिग्रहणस्य चारितार्थ्येन सामर्थ्यं दुरुपपादम् । अनुवर्तमानस्य स्वरूपपरत्वेन निषेध्यसमर्पकत्वाभावादिति चेत्, न । आगन्तूनामन्ते निवेश इति न्यायेनादेङ्सूत्रे गुणपदोत्तरं वृद्धिपदोपस्थित्या तत्साहचर्येण तत्र सूत्रे स्वरूपपरत्वं तस्य, उत्तरत्र तु योग्यतयाऽर्थपरत्वम् । इक इति सूत्रेऽपि न धात्विन्त्यादिसाहचर्येणार्थपरत्वं, 'इकः' इति षष्ठीनिर्देशाच्चेति भाष्याशयात् ॥

(१ समाधानभाष्यम्)

संबन्धमनुवर्तिष्यते—"वृद्धिरादैच्" "अदेङ्गुणः" वृद्धिरादैच् ततः—"इको गुणवृद्धी" इति । गुणवृद्धिग्रहणमनुवर्तते, आदैजदेङ्ग्रहणं निवृत्तम् ॥

(प्रदीपः) संबन्धमिति । संबध्यत इति संबन्धं, कर्मणि घञ् । नपुंसकस्याभिधेयत्वान्नपुंसकनिर्देशः । आदैज्ग्रहणसंबन्धं वृद्धिग्रहणमदेङ्गुण इत्यत्रानुवर्तते, तेनादेङ्भिर्न संबध्यते । इह त्वनुवृत्तमादैचो जहाति । कान्तारोत्तारणाय सार्थस्येव त्यागोपादाने ॥

(उद्द्योतः) नपुंसकस्येति । घञजपः पुंसीति तु प्रायिकमिति भावः ॥ यत्तु भावविषयमेवैतदिति । तन्न । 'मर्सि भक्षोऽस्य' इति कर्मण्यणिति सूत्रस्थभाष्यप्रयोगविरोधात् ॥ तेनेति । अत्रादैजित्यनुवृत्तिर्न स्वकार्याय, किं तु वृद्धिशब्दस्यान्यसंबन्धनिवृत्तये— इति भावः ॥ भाष्ये वृद्धिरादैजदेङ्गुण इति सूत्रक्रमनिर्देशः । पुनर्वृद्धिरादैजित्यभिधानमदेङित्यत्र संबन्धानुवृत्तिं दर्शयितुम् ॥ इको गुणवृद्धी इत्युक्तिस्तु यथान्यासाभिप्रायेण ॥ आदैजदेङ्ग्रहणमिति । स्वरितत्वाप्रतिज्ञानेनादेङ्ग्रहणवदादैजित्यपि निवृत्तमित्यर्थः ॥ क्वचित्तु आदैज्ग्रहणं निवृत्तमित्येव पाठः ॥

(२ समाधानभाष्यम्)

अथवा मण्डूकगतयोऽधिकाराः । यथा मण्डूका उत्प्लुत्योत्प्लुत्य गच्छन्ति तद्वदधिकाराः ॥

(प्रदीपः) अथवेति । वृद्धिशब्दस्येहाकाङ्क्षावशादुपस्थानं, न तु 'अदेङ्गुणः' इत्यत्र ॥

(उद्द्योतः) ननु मण्डूकस्य चेतनत्वात्तथा गतिसंभवेऽपि शब्दस्य कथं सेत्यत आह—वृद्धिशब्दस्येति । स्वरितत्वासत्त्वादनुवर्तमानस्यापीति शेषः ॥ इहेति । इक इति सूत्र इत्यर्थः । अदेङित्यत्र तु न संबन्धः, गुणसंज्ञासंबन्धेनादेङां निराकाङ्क्षत्वादिति बोध्यम् ॥

(३ एकदेशिसमाधानभाष्यम्)

अथवैकयोगः करिष्यते—"वृद्धिरादैजदेङ्गुणः" ततः—"इको गुणवृद्धी" इति । न चैकयोगेऽनुवृत्तिर्भवति ॥

(प्रदीपः) अथवैकयोग इति । एको भवतिरध्याह्रियते । वृद्धिरादैजदेङ्गुणो भवति इत्येकवाक्यत्वं संपद्यते । यद्यपि प्रतिपत्तिकाले भवतिक्रिया भिद्यते, तथाप्येककाला प्रतिपत्तिरित्यादैच्संबद्धा वृद्धिसंज्ञाऽदेङ्संबद्धा गुणसंज्ञेति नास्ति वृद्धिसंज्ञाया अदेङ्भिः संबन्धः ॥

(उद्द्योतः) नन्वेकयोगत्वं नैकार्थत्वं, भिन्नविषयसंज्ञाद्वयविधानात् । नापि निरन्तरपाठः, तस्येदानीमपि सत्त्वेन करिष्यत इत्यस्यासङ्गतेः । णेरणावित्यादौ एकयोगेऽप्यनुवृत्तिदर्शनाच्च अत आह—एक इति ॥ प्रतिपत्तिकाले=लक्ष्यसंस्कारकवाक्योपप्लवकाले ॥ एककालेति । आदैच् वृद्धिसंज्ञः, अदेङ् गुणसंज्ञो भवतीति संग्राहकवाक्यार्थबोध एककाल इति भावः ॥ समूहालम्बनात्मक एको वाक्यार्थबोध इति तात्पर्यम् ॥ यद्वा—आदैच् वृद्धिसंज्ञोऽदेङ्गुणसंज्ञश्च भवत इत्येको वाक्यार्थबोध इति तात्पर्यम् । प्रतिपत्तिः=वाक्यार्थबोधः । णेरणावित्यादाववान्तरवाक्यार्थभेदान्न दोषः ॥ केचित्तु एककाला प्रतिपत्तिर्भवतु, तावता स्वरितत्वगुणप्राप्तवृद्धिपदसंबन्धाभावः कुत इति चिन्त्यम् । न च स्वविषयवाक्यजबोधानन्तरं निराकाङ्क्षतयाऽन्यत्रान्वयाप्रसक्तौ हि तत्प्राप्तये स्वरितासङ्गो न चैतदेकयोग इति वाच्यम् । व्यवधाननिबन्धनायामनेकसंबन्धाप्राप्तावनेकसंबन्धाय स्वरितत्वासङ्ग इत्यस्यापि वक्तुं शक्यत्वात् ॥ तस्मादयमत्र भाष्यार्थः—तदधीते तद्वेदेत्यत्र द्वितग्रहणादेकयोगेऽनुवृत्त्यभावः—इति । स्पष्टं चेदं तदस्मिन्नस्तीति सूत्रे भाष्ये । एकयोगत्वं च द्वयोः संहितापाठ एव ॥ वस्तुत एकयोगेऽप्यनुवृत्तिर्भवति, तदस्यास्त्यस्मिन्निति सूत्रे द्वितग्रहणाभावात्, तदधीत इति सूत्रे तु बालानां सुखबोधाय द्वितग्रहणमित्यप्युक्तं तत्रैव । अतोऽत्र भाष्येऽयं समाधिरेकदेशिन इत्याहुः ॥

(४ समाधानभाष्यम्)

अथवा—

* अन्यवचनादकाराकरणाच्च प्रकृतापवादो विज्ञायते, यथोत्सर्गेण प्रसक्तस्यापवादो बाधको भवति * ॥

अन्यस्याः संज्ञाया वचनाच्चकारस्य चानुकर्षणार्थस्याकरणात्प्रकृताया वृद्धिसंज्ञाया गुणसंज्ञा बाधिका भविष्यति । यथोत्सर्गेण प्रसक्तस्यापवादो बाधको भवति ॥

(प्रदीपः) अथवान्यवचनादिति । यथा कप्रत्ययेनाण् बाध्यते, असंदिग्धत्वादनवकाशत्वात्तात्पर्याच्च कविधेः । अणस्तु विपर्ययात् । एवमदेङ्गुण इत्यत्र वृद्धिग्रहणमनुवृत्तं सत्संदिह्यते—किमुत्तरार्था वेहानुवृत्तिरथेहार्थापीति । सावकाशा च वृद्धिसंज्ञा, तात्पर्यं च नास्ति । गुणसंज्ञा तु तात्पर्यादसंदेहान्निरवकाशत्वाच्च वृद्धिसंज्ञासंबन्धमदेङां बाधते । प्रत्ययसंज्ञा तु संज्ञिविशेषेणासंयुक्ताऽधिकारेणैव विधीयमाना कृत्यादिसंज्ञाविषयेऽपि प्रवर्तते ॥

(उद्द्योतः) ननु वृद्धिगुणसंज्ञयोः सामान्यविशेषत्वाभावात्कथमुत्सर्गत्वादसाम्यमत आह—यथेति । अस इत्युपादानादेव तद्विषये कस्यासंदिग्धत्वम् । अत एव तदतिरिक्तावकाशविरहः, तदुद्देशेनैव प्रकृतिरूपं तात्पर्यं च ॥ ननु गुणसंज्ञया वृद्धिसंज्ञावत् कृत्यादिसंज्ञयाऽपि प्रत्ययसंज्ञा बाध्येतेत्यत आह—प्रत्ययेति । न तव्याद्याकाङ्क्षया प्रत्ययसंज्ञायाः संबन्धः, येन संनिहितकृत्यादिसंज्ञया निराकाङ्क्षत्वात्प्रत्ययसंज्ञया संबन्धः स्यात् । किं तु संज्ञाऽऽकाङ्क्षया ॥ सा हि स्वस्य बहुविषयत्वलाभाय कतिपयानन्तरविषयलाभेऽपि पुनः पुनर्विषयान्तरमाकाङ्क्षते । बहुविषयत्वं चास्याः संज्ञिविशेषासंबन्धेन धिकारकरणादवसीयत इति भावः ॥ प्रकृते तु न तथेति बोध्यम् ॥

(५ समाधानभाष्यम्)

अथवा वक्ष्यत्येतत्—"अनुवर्तन्ते च नाम विधयः, न चानुवर्तनादेव भवन्ति । किं तर्हि ? यत्नाद्भवन्ति" इति ॥

(प्रदीपः) अथवेति । 'विभाषा तिलमाषोमा- इत्यत्र भङ्गाणुभङ्गयोरधान्यत्वात्खञोऽप्राप्तौ चोदितायां खञ्ग्रहणस्यानुवृत्तिराश्रिता, अनुवर्तमानश्च खञ् यत्नाभावात् व्रीहिशाल्यादिभिर्न संबध्यते, अपि तु विभाषाश्रुत्या यत्नेन तिलादिभिरेव संबध्यते । तथेहापि वृद्धिग्रहणमदेङ्गुण इत्यत्रानुवर्तमानमपि यत्नाभावादेङ्भिर्न संबध्यते । इह पुनर्गुणवृद्धिग्रहणं यत्नो भवति ॥

(उद्द्योतः) खञोऽप्राप्ताविति । यता मुक्ते-इति शेषः । मण्डूकगतयोऽधिकारा इत्यस्यैव 'स्वरितलिङ्गेनानुवर्तमानं यत्राकाङ्क्षा तत्रैव संबध्यते' इति विशेषमभिधातुमयं पक्षः । स च संबन्धाय तत्र विभाषाग्रहणरूपं यत्नविशेषं कुर्वतः सूत्रकृतोऽप्यभिमतः । अस्य विशेषस्य प्रागकथनं तु एतद्विशेषद्वारा पुनस्तत्परामर्शेन तत्रैव परिहारे मुख्यताबोधनायेति बोध्यम् ॥ इह त्विति । अकर्तव्यत्वविशिष्टं पुनर्गुणवृद्धिग्रहणं यत्न इत्यर्थः । अनुवृत्तौ हि तदकर्तव्यं भवतीत्याशुः ॥

(६ समाधानभाष्यम्)

अथवा—उभयं निवृत्तम् । तदपेक्षिष्यामहे ॥

(प्रदीपः) अथवेति । अपेक्षालक्षणं लौकिकमधिकारमाश्रयति । समुदायस्य चापेक्षायां नास्त्येतत्—अनन्तरस्य विधिर्वा भवति प्रतिषेधो वेति गुणस्यैवापेक्षा युक्ता—इति, समुदायस्य भेदाभावात् ॥

(उद्द्योतः) भाष्ये—उभयं निवृत्तमिति । स्वरितलिङ्गानासङ्गेनाननुवृत्तिरेव निवृत्तिरित्यर्थः ॥ अपेक्षेति । 'इकः' इत्येतावन्मात्रस्येतराकाङ्क्षत्वात् । समुदायापेक्षायां च लक्ष्यानुसार एव बीजम् । अनन्तरस्येति न्यायेन गुणस्यैवापेक्षा युक्तेत्येतन्नास्ति-इत्यन्वयः । समुदायत्वं च युगपद्बुद्धौ संनिधानात् क्रमेणासंनिधानाच्चेति बोध्यम् ॥

(इति गुणवृद्धिशब्दानुवृत्त्यधिकरणम्)

—————

(अथ परिभाषात्वसाधकाधिकरणम्)

(पक्षद्वयोपस्थापकभाष्यम्)

किं पुनरयमलो न्त्यशेषः, आहोस्विदलोऽन्त्यापवादः ?

कथं चायं तच्छेषः स्यात्, कथं वा तदपवादः ?

यद्येकं वाक्यम्—तच्चेदं च, अलोऽन्त्यस्य विधयो भवन्ति–'इको गुणवृद्धी अलोऽन्त्यस्य' इति । ततोऽयं तच्छेषः ॥

अथ नानावाक्यम्, 'अलोऽन्त्यस्य विधयो भवन्ति','इको गुणवृद्धी–अन्त्यस्य चानन्त्यस्य च' इति । ततोऽयं तदपवादः ॥

(प्रदीपः) किं पुनरिति । उभयथा संभवादेषदकथाच्च प्रश्नः । तत्राङ्गस्य गुण इति षष्ठीनिर्देशाज्ज्ञात 'अलोन्त्यस्य' इत्युपतिष्ठते, गुणश्रुत्या तु 'इकः' इति । तत्र यदि पूर्वमिकाऽङ्गं विशेष्यते—इगन्ताङ्गस्य गुणो भवतीति, स च भवन्नलोन्त्यस्येत्यन्त्यस्य भवति, तदा सोऽस्य शेषो भवति ॥ यदा त्वङ्गस्येति पूर्वमेवान्त्यमलं षष्ठी नीयते—अङ्गान्त्यस्य गुण इति पश्चादिकाऽन्त्योऽल् विशेष्यते, तदा तस्यायं विशेषणत्वाच्छेषो भवति ॥

अथ तु 'अङ्गस्य' इति गुणवृद्धिविधौ न स्थानषष्ठी, किं तर्हि ? इगपेक्षयाऽवयवषष्ठी, तदा स्थानषष्ठ्यभावात् 'अलोऽन्त्यस्य' इत्यस्यानुपस्थानमिति तदपवादपक्षो भवति । अत्राप्यनुमानमेव हि बाधः, वचनेन प्राप्तस्य बाधायोगात् । ततश्चाङ्गावयवस्य यत्र तत्र स्थितस्येको गुणवृद्धी इत्यर्थः संपद्यते ॥ समुच्चयस्त्वसंभवाद्रोपन्यस्तः । न हि युगपद्द्वौ षष्ठ्यर्थौ संभवतः—स्थानेयोगोऽवयवयोगश्च–इति ॥ विकल्पोऽपि न भवति, एकत्वात्षष्ठ्यर्थस्य । तस्माच्छेषत्वतदपवादपक्षावेवात्राश्रितौ ॥

यद्येकमिति । अनेकयोगव्यवहितयोरपि एकस्मिन्कार्यदेशे स्वस्वनिमित्तसंनिधापिनयोरङ्गाङ्गिभावात्–विशेषणविशेष्यभावादेकवाक्यत्वोपपत्तिः ॥ अथ नानेति । अङ्गस्येतीगपेक्षयाऽवयवषष्ठ्यामिकः स्थानित्वात्तद्विशेषणत्वादङ्गस्यानुपस्थानमलोऽन्त्यस्येत्यस्य । ततश्चानयोर्भिन्नविषयत्वान्नानावाक्यत्वम् ॥

(उद्द्योतः) षष्ठीति । स्थानषष्ठीत्यर्थः । 'षष्ठी स्थाने' इति परिभाषस्य तत्त्वनिर्णयः । अस्य च सूत्रस्य गुणवृद्धिशब्दाभ्यां विधीयमानौ वृद्धिगुणौ 'इकः स्थाने' इत्यर्थेऽवान्तरवाक्यार्थबोधोत्तरमेव प्रवृत्तेरुभयोरपि समकालप्रवृत्तिकता बोध्या । गुणश्रुत्येत्यस्य गुणशब्देन विधेयबोधकतयेत्यर्थः ॥ तत्र यदीति । वृद्धेः कर्मित्वादिविशेषणविशेष्यभावे कामचाराच्चेति भावः ॥ सोऽस्येति । इगन्तस्येति षष्ठ्यास्तेनान्त्येऽल्यनुसंहारादेतद्विशेषणत्वं-एतत्परिच्छेदकत्वं तस्येति भावः ॥ तदा तस्यायं विशेषणत्वादिति । तच्छेषशब्दे तन्त्रेण बहुव्रीहिषष्ठीतत्पुरुषाविति भावः ॥

[भाष्ये 'इको गुणवृद्धी' इति पूर्वपरान्वयि, तेन तद्द्वयलाभ इति भावः ॥ परिच्छेदकभावकृत एव च शेषित्वव्यवहार इति बोध्यम् ॥]

अथ स्थितिरिति । अवान्तरवाक्यार्थबोधकालेऽनिर्णीतार्थकत्वेन स्थानषष्ठीत्वसंभावनया तत्प्रवृत्तावपि पश्चादिक इत्यस्योपस्थितौ मिदेरित्यादौ योग्यत्वेन तत्साहचर्येण चान्यत्राप्यवयवषष्ठीत्वनिर्णये तदसंबन्ध इति भावः ॥ बाधायोगादिति । आत्यन्तिकबाधायोगादित्यर्थः । पाक्षिकस्तु बाधः पोडशीग्रहणादौ भवत्येवेति बोध्यम् ॥ समुच्चय इति । मिदेरन्त्यस्येकश्चेत्येवमाकारः ॥ न हीति । प्रत्यर्थं शब्दनिवेशेनैकस्य नानेकार्थाभिधायकत्वम् । तत्रे आवृत्तौ च न मानमिति भावः ॥

अनेकयोगेति । एवं चैकं वाक्यमिति भाष्यमयुक्तमिति भावः ॥ उत्तरम्—एकस्मिन्नित्यादि ॥ अङ्गाङ्गिभावश्च न गुणगुणिभाव इत्याह—विशेषणेति ॥ इकः स्थानित्वादिति । सा च नालोऽन्त्यसूत्रप्रवृत्तौ निमित्तम्, अल्समुदायेतरस्थानषष्ठीत्वाभावात् । 'अङ्गस्य' इति च न स्थानषष्ठीति भावः ॥ सद्विशेषणत्वादिति । अवयवित्वेन विशेषणत्वादित्यर्थः ॥ नानावाक्यत्वमिति । अत्र पक्षे पुगन्तेत्यादि नियमार्थमिति बोध्यम् ।

(भाष्यम्)

कस्तर्हि विशेषः ?

(७ तच्छेषपक्षदूषणवार्तिकम् ॥ ३ ॥)

॥ * ॥ वृद्धिगुणावलोऽन्त्यस्येति चेन्मिदिमृजिपुगन्तलघूपधर्च्छिदृशिक्षिप्रक्षुद्रेष्विग्ग्रहणम् ॥ * ॥

(व्याख्याभाष्यम्)

वृद्धिगुणावलोऽन्त्यस्येति चेन्मिदिमृजिपुगन्तलघूपधर्च्छिदृशिक्षिप्रक्षुद्रेष्विग्ग्रहणं कर्तव्यम् ॥

"मिदेर्गुणः" (७।३।८२), इक इति वक्तव्यम् । अनन्त्यत्वाद्धि न प्राप्नोति ॥

"मृजेर्वृद्धिः" (७।२।११४), इक इति वक्तव्यम् । अनन्त्यत्वाद्धि न प्राप्नोति ॥

"पुगन्तलघूपधस्य" (७।३।८६) गुणः, इक इति वक्तव्यम् । अनन्त्यत्वाद्धि न प्राप्नोति ॥

ऋच्छेर्लिटि गुणः (७।४।११), इक इति वक्तव्यम् । अनन्त्यत्वाद्धि न प्राप्नोति ॥

दृशेः "ऋदृशोऽङि गुणः" (७।४।१६), इक इति वक्तव्यम् । अनन्त्यत्वाद्धि न प्राप्नोति ॥

क्षिप्रक्षुद्रयोर्गुणः (६।४।१५६), इक इति वक्तव्यम् । अनन्त्यत्वाद्धि न प्राप्नोति ॥

(प्रदीपः) वृद्धिगुणाविति । मिदादीनामनिगन्तत्वादलोऽन्त्यस्येत्येतदस्मिन्ग्रहणं न सन्निपततीति तेषु प्रदेशेष्विग्ग्रहणं कर्तव्यम् ॥

(उद्द्योतः) मिदादीनामिति । गुणादिविधौ परिभाषाद्वयस्य परस्परसंबन्धापरित्यागेनोपस्थानं तच्छेषत्वम् । तत्रैकस्या असंभवे द्वितीयाऽपि न प्रवर्तत इति भावः ॥ भाष्ये—अनन्त्यत्वाद्धीति । तच्छेषपक्षेऽनन्त्यत्वादिको गुणो न प्राप्नोतीत्यर्थः ॥

(७७ तच्छेषदूषणान्तरवार्तिकम् ॥ ४ ॥)

॥ * ॥ सर्वादेशप्रसङ्गश्चानिगन्तस्य ॥ * ॥

(एकदेशिव्याख्याभाष्यम्)

सर्वादेशश्च गुणोऽनिगन्तस्य प्राप्नोति । याता, वाता ॥

किं कारणम् ?

"अलोऽन्त्यस्य" इति षष्ठी । षष्ठी चैव ह्यन्त्यमिकमुपसंक्रान्ता, अङ्गस्येति च स्थानषष्ठी । तद्यदिदानीमनिगन्तमङ्गं तस्य गुणः सर्वादेशः प्राप्नोति ॥

(प्रदीपः) दोषान्तरमप्याह — सर्वादेशप्रसङ्गश्चेति । अङ्गस्येत्येतद्भेदेन सर्वाङ्गेषु व्याप्रियते । तत्रेगन्तेष्वेव 'अलोऽन्त्यस्य' इति विधिरन्यत्र तु षष्ठ्या अन्त्येऽल्यनुपसंहारात्—याता—वाता—इति सर्वादेशो गुणः प्राप्नोति ॥

(उद्द्योतः) अङ्गस्येति च स्थानषष्ठीति । अङ्गस्य स्थाने गुणो भवति । स च यत्रान्त्य इक् तत्रान्त्यस्येक इत्यर्थं इत्यभिमानः । तदाह—भेदेनेति । शास्त्रस्य बहुविषयत्वायेत्यर्थः ॥ तत्रेगन्तेष्वेवेति । तच्छेषत्वादिति भावः ॥ अन्यत्र—अनिगन्तविषये गुणशास्त्रे ॥

(दूषणोद्धारभाष्यम्)

नैष दोषः । यथैव ह्यलोऽन्त्यस्येति षष्ठी अन्त्यमिकमुपसंक्रान्ता, एवमङ्गस्येत्यपि स्थानषष्ठी । तद्यदिदानीमनिगन्तमङ्गं तत्र षष्ठ्येव नास्ति, कुतो गुणः कुतः सर्वादेशः ॥

(प्रदीपः) यथैव हीति । 'अङ्गस्य' इति षष्ठी उच्चारितैवान्त्यमलं नीतेति नास्या अपरं रूपमस्तीति नास्ति सर्वादेशगुणप्रसङ्गः ॥

(उद्द्योतः) अन्त्यमलमिति । इक्परिभाषाशेषभूतालोऽन्त्यपरिभाषयेत्यर्थः ॥ अङ्गस्येत्यपि स्थानषष्ठीति भाष्ये—अन्त्यमिकमुपसङ्क्रान्तेत्यनुकर्षः । एवं च संग्राहकवाक्यस्येगन्तमात्रविषयत्वादनिगन्तविषयकलक्षणाभाव एव । आवृत्तौ च न मानमिति भावः । अत एव गापोष्टक् इत्यपि सार्थकम् ॥

(वार्तिकसमन्वयाक्षरभाष्यम्)

एवं तर्हि नायं दोषसमुच्चयः ॥

किं तर्हि ?

पूर्वापेक्षोऽयं दोषः । अर्थे चायं च पठितः—

*मिदिमृजिपुगन्तलघूपधर्च्छिदृशिक्षिप्रक्षुद्रेष्विग्ग्रहणं सर्वादेशप्रसङ्गो ह्यनिगन्तस्य * इति ।

मिदेर्गुणः 'इकः' इति वचनादन्त्यस्य न, 'अलोऽन्त्यस्य' इति वचनादिको न । उच्यते च गुणः । स सर्वादेशः प्राप्नोति ॥ एवं सर्वत्र ॥

(प्रदीपः) पूर्वापेक्षोऽयमिति । 'मिदादिष्विग्ग्रहणं कर्तव्यम्' इत्यत्रैवार्थे हेतुत्वेनेदमुपात्तमित्यर्थः ॥ उच्यते चेति । 'मिदेर्-' इति चोदनया ॥

(उद्द्योतः) इक्ष इत्यर्थं एवाह—मिदादिष्विति ॥

(इति तच्छेषपक्षदूषणम् ।)

(अथ तदपवादपक्षाभ्युपगमभाष्यम्)

अस्तु तर्हि तदपवादः ॥

(७८ तदपवादपक्षदूषणवार्तिकम् ॥ ५ ॥)

॥ * ॥ इग्लक्षणाङ्गस्येति चेज्जुसिसार्वधातुकार्धधातुकह्रस्वाद्योर्गुणेष्वनन्त्यप्रतिषेधः ॥ * ॥

(भाष्यम्)

इग्लक्षणाङ्गस्येति चेज्जुसिसार्वधातुकार्धधातुकह्रस्वाद्योर्गुणेष्वनन्त्यस्य प्रतिषेधो वक्तव्यः ॥

जुसि (७।३।८३) गुणः, स यथेह भवति-'अजुहवुः-अबिभयुः' इति, एवम्-'अनेनिजुः-पर्यवेविजुः' अत्रापि प्राप्नोति ॥

सार्वधातुकार्धधातुकयोः (७।३।८४) गुणः, स यथेह भवति-'कर्ता-हर्ता-जयति-तरति-भवति', एवम्-'ईहिता-ईहितुम्-ईहितव्यम्' इत्यत्रापि प्राप्नोति ॥

ह्रस्वस्य (७।३।१०८) गुणः, स यथेह भवति-'हे अग्ने-हे वायो' इति, एवं-'हे अग्निचित्-हे सोमसुत्' इत्यत्रापि प्राप्नोति ॥

जसि (७।३।१०९) गुणः, स यथेह भवति-'अग्नयः-वायवः' इति, एवं-'अग्निचितः-सोमसुतः' इत्यत्रापि प्राप्नोति ॥

ऋतो ङिसर्वनामस्थानयोः (७।३।११०) गुणः, स यथेह भवति-'कर्तरि-कर्तारौ-कर्तारः' इति, एव-'सुकृति-सुकृतौ-सुकृतः' इत्यत्रापि प्राप्नोति ॥

घेर्ङिति (७।३।१११) गुणः, स यथेह भवति—'अग्नये-वायवे' इति, एवम्-'अग्निचिते-सोमसुते' इत्यत्रापि प्राप्नोति ॥

ओः (६।४।१४६) गुणः, स यथेह भवति-'बाभ्रव्यः-माण्डव्यः' इति, एवं-'सुश्रुत्-सौश्रुतः' इत्यत्रापि प्राप्नोति ॥

(प्रदीपः) इग्लक्षणाङ्गस्येति । यद्यङ्गस्येतीगपेक्षयाऽवयवषष्ठी तदा 'अलोऽन्त्यस्य' इत्यस्य निमित्ताभावादनुपस्थानम्, स्थानषष्ठी हि अस्योपस्थाने निमित्तम् । ततश्चाङ्गावयवस्यान्त्यस्यानन्त्यस्य चेको गुणः प्राप्नोतीति दोषः ॥ ह्रस्वस्य गुण इति । समानन्यायत्वादेतदुक्तम् । अङ्गस्यावयवो यो ह्रस्वस्तस्य गुण इति । न त्वत्रेक्परिभाषोपतिष्ठते, निर्दिष्टस्थानिकत्वात् ॥ अन्ये त्वाहुः—अत्रापि परिभाषोपस्थाने सति ह्रस्वेनेग्विशेष्यते—ह्रस्वस्येको गुणो यथा स्यात्, दीर्घस्य मा भूदिति ॥ ओर्गुण इति । अत्राप्यस्या उपस्थानमनन्त्यस्याप्युकारस्य गुणार्थम् । असति ह्यस्या उपस्थानेऽङ्गस्येति स्थानषष्ठी स्यादङ्गं चोकारेण विशेष्यत इत्युकारान्तस्यैवाङ्गस्य गुणः स्यात् ॥

(उद्द्योतः) अनन्त्यस्य चेक इति । यद्यपि जुसि चेत्यादीनां प्रधानभूतेग्विशेषणत्वे तस्मिन्निति परिभाषया व्यवहितस्येको न भविष्यति, तथापि प्रत्ययस्याङ्गांशे उपस्थिताकाङ्क्षतया जुसि चेत्यादिभिरप्यङ्गमेव विशेष्यत इत्यभिप्रायः ॥ समानन्यायेति । गुणप्रकरणावैरूप्याय सर्वत्राङ्गस्येत्यवयवषष्ठ्येव स्यादिति भावः ॥ निर्दिष्टेति । अनियमे नियमकारिणीत्वात्परिभाषाया इति भावः ॥ अन्ये त्विति । अयं भावः—न ह्यनियम इति श्रुतिः स्मृतिर्वा, किं तु परिभाषा लिङ्गवती फलवती चेति नियमः, फलं चेतरव्यावृत्तिवदितरसंग्रहोऽपीति ह्रस्वस्येत्यस्याङ्गविशेषणत्वव्यावर्तनेनावयवषष्ठीत्वबोधनेनानन्त्यस्यापि गुणसम्पादनमेव फलं स्यात् । अकारे गुणागुणयोर्न विशेष इति ॥ तदेतद्ध्वनयति—अनन्त्यस्याप्युकारस्येति ॥ नन्वेवं ह्रस्वग्रहणं व्यर्थमत आह—दीर्घस्येति ॥ घिसंज्ञा वर्णयोरेवेति पक्षे ङिति गुणस्य 'अग्निचिते' इत्यादौ प्रसङ्गो बोध्यः ॥

(भाष्यम्)

नैष दोषः ।

(७९ सिद्धान्त्येकदेशिवार्तिकम् ॥ ६ ॥)

॥ * ॥ पुगन्तलघूपधग्रहणमनन्त्यनियमार्थम् ॥ * ॥

(भाष्यम्)

पुगन्तलघूपधग्रहणमनन्त्यनियमार्थं भविष्यति—पुगन्तलघूपधस्यैवानन्त्यस्य नान्यस्यानन्त्यस्येति ॥

(प्रदीपः) पुगन्तेति । भेत्तेत्यादौ गुणे सिद्धे पुनःश्रुतिर्नियमार्थेति गुरूपधस्य 'ईहिता' इत्यादौ न भविष्यति । नापि हे अग्निचिदित्यादौ, उभयनियमाश्रयणादिति भावः ॥ ननु च भेत्तेति दकारस्य ह्लेपयतीति पकारस्य च यथा स्यादिति विध्यर्थमेतत्स्यात् । नैतदस्ति, पुकि अन्तः—पुगन्तः, लघ्वी उपधा—लघूपधा, ततः समाहारद्वन्द्वनिर्देश इत्यन्त्यस्य गुणेन भाव्यम् ॥

(उद्द्योतः) पुनःश्रुतिः—पुनर्गुणविधानम् ॥ ननु चेति । बहुव्रीहिसमासः, सामर्थ्यादिक्परिभाषाऽनुपस्थितिश्चेति भावः ॥ भिदो

दकारोच्चारणं तु भिन्नो भित्तमित्यादौ चरितार्थम्, क्नोः कित्त्वेनानिष्लक्षणत्वेऽपि निषेधप्रवृत्तेः । पुग्विधानमपि क्ष्मापयतीत्यादौ यलोपार्थम्, ओकाररूपगुणार्थं च चरितार्थमित्याशयः ॥ पुकीति । आपवाद्यत्वे निर्णीते नियमार्थत्वं न दोषावहमित्यर्थः ॥ ननु पुगन्तग्रहणं दापयतीत्यादौ अनन्त्यस्थानिकोऽपि गुणार्थं स्यादिति कथं नियमार्थत्वमिति चेन्न । गुणे उपधावृत्त्या विशेषाभावात् ॥

(नियमदूषणभाष्यम्)

प्रकृतस्यैव नियमः स्यात् ॥

किं च प्रकृतम् ?

सार्वधातुकार्धधातुकयोरिति । तेन भवेदिह नियमान्न स्यात्-'ईहिता-ईहितुम्-ईहितव्यम्' इति । ह्रस्वाद्योर्गुणस्त्वनियतः सोऽनन्त्यस्यापि प्राप्नोति ॥

(प्रदीपः) **प्रकृतस्येति** । एकेन वाक्येन नियमद्वयस्यालाभात्प्रकृतस्यैव गुणस्य नियमः स्यात्—पुगन्तलघूपधस्यैव सार्वधातुकार्धधातुकयोरिति, न तु सार्वधातुकार्धधातुकयोरेव पुगन्तलघूपधस्येति ॥

(उद्द्योतः) **प्रकृतस्यैवेति** । अनन्तरस्यैवेत्यर्थः ॥

(नियमान्तरदूषणभाष्यम्)

अथाप्येवं नियमः स्यात्—पुगन्तलघूपधस्य सार्वधातुकार्धधातुकयोरेवेति ॥

एवमपि सार्वधातुकार्धधातुकयोर्गुणोऽनियतः सोऽनन्त्यस्यापि प्राप्नोति—ईहिता-ईहितुम्-ईहितव्यमिति ॥

(प्रदीपः) **अथापीति** । **अनन्तरस्य विधिर्वेति** परिभाषा यदि नाश्रीयते-इति भावः ॥

(उद्द्योतः) नन्वनन्तरस्येति न्यायविरुद्धोऽयं नियम इत्यत आह—**अनन्तरस्येति** । लक्ष्यानुसारश्चानाश्रयणे बीजं बोध्यम् ॥

(उभयविधनियमदूषणभाष्यम्)

अथाप्युभयतो नियमः स्यात्—पुगन्तलघूपधस्यैव सार्वधातुकार्धधातुकयोः, सार्वधातुकार्धधातुकयोरेव पुगन्तलघूपधस्येति ॥

एवमप्ययं जुसिगुणोऽनियतः सोऽनन्त्यस्यापि प्राप्नोति-'अनेनिजुः-पर्यवेविषुः' इति ॥

(प्रदीपः) **अथापीति** । अभ्युपेत्यवादेनोच्यते, आवृत्त्यादिन्यायाश्रयणेन वा । एकस्मिंस्तु वाक्ये नियमद्वयं न लभ्यते ॥ **एवमपीति** । अनेनिजुः पर्यवेविषुरित्यत्र लघूपधं चाङ्गं सार्वधातुकं चास्तीति जुसि चेति गुणः प्राप्नोति । हे पिचव्य हे बुद्धे बुद्धये बुद्धय इत्यादौ चालघूपधत्वादनन्त्यस्य गुणोऽपरिहृतः ॥

(उद्द्योतः) **अभ्युपेत्यवादः**-क्लेशेनाङ्गीकार **इत्याहुः** ॥ **पिचव्येति** । उगवादियत् । उवर्णान्तस्याङ्गस्येको गुण इति व्याख्यानमभिप्रेत्यात्र दोषोपन्यासः ॥ परंतु **सौश्रुत इत्यत्रापि प्राप्नोतीति** भाष्याननुगुणा सा व्याख्येति चिन्त्योऽयं कैयट इत्याहुः ॥ क्वचित्तु कैयटपुस्तके 'पिचव्य' इति न दृश्यत एव ॥

(इति तदपवादपक्षदूषणप्रकरणम्)

(यथासंबद्धपरिभाषानिरासाधिकरणम्)

(भाष्यम्)

एवं तर्हि—नायं तच्छेषः, नापि तदपवादः । अन्यदेवेदं परिभाषान्तरमसंबद्धमनया परिभाषया ॥

(प्रदीपः) **एवं तर्हीति** । परस्परानपेक्षयोः स्वस्वनिमित्तप्रयुक्तसंनिधानयोर्द्वयोः परिभाषयोः प्रदेशेषु स्वकार्यप्रतिपादनम् । तत्र यदि कथंचिदेकस्मिन् विषये संनिपातो भवति, नैतावता परस्परापेक्षा भवतीत्यर्थः ॥ **अन्यदेवेति** । अन्तरशब्दो विशेषवाचीति अन्यान्तरशब्दयोरविरुद्धः प्रयोगोऽपर्यायत्वात् ॥

(उद्द्योतः) तच्छेष इति शब्दोऽसंभवदुक्तिकस्तथास्तोऽपीत्याह—**परस्परेति** । विशेषणविशेष्यभावमात्रेण शेषशेषिव्यवहारो न क्वापि दृष्टचर इति भावः ॥ अत एवाग्रे एतत्पक्षोक्तदूषणोद्धारेऽपि नायं तच्छेष इत्युक्तिः संगच्छते ॥ **संनिपात इति** । जायमानोऽपि संनिपातः सावकाशत्वेन विप्रतिषेधोपयोग्येव, न तच्छेषत्वोपयोगी । अत एव नापवादत्वमपि । उक्तदोषाभावेति भावः ॥ **असंबद्धमनयेति** भाष्यस्य—शेषशेषिभावानापन्नमुत्सर्गापवादभावानापन्नं चेत्यर्थः ॥

(परिभाषान्तरपक्षसमर्थकभाष्यम्)

परिभाषान्तरमिति च मत्वा क्रोष्ट्रीयाः पठन्ति—

(क्रोष्ट्रीयवार्तिकम्)

***नियमादिको गुणवृद्धी भवतो विप्रतिषेधेन* इति ॥**

(भाष्यम्)

यदि चायं तच्छेषः स्यात्, तेनैव तस्यायुक्तो विप्रतिषेधः । अथापि तदपवादः, उत्सर्गापवादयोरप्ययुक्तो विप्रतिषेधः ॥ तत्र नियमस्यावकाशः—"राज्ञः क च" राजकीयम् । "इको गुणवृद्धी" इत्यस्यावकाशः—चयनं चायको लवनं लावकः । इहोभयं प्राप्नोति-'मेद्यति-मार्ष्टि' इति । "इको गुणवृद्धी" इत्येतद्भवति विप्रतिषेधेन ॥

(प्रदीपः) **चयनमिति** । अलोऽन्त्यपरिभाषायाः प्रयोजनाभावादत्रानुपस्थानमित्याशयः ॥ **चायक इति** । कथमत्रेक्परिभाषोपतिष्ठते यावताऽच इति स्थानी निर्दिष्टः । अत्राहुः—अच इत्यस्याङ्गविशेषणतयोपयोगादचः स्थानित्वाभावाद्वृद्धिग्रहणेन लिङ्गेनेक्परिभाषाऽत्राप्युपतिष्ठत एव ॥ **मेद्यतीति** । इक इति वचनादिकारस्य प्राप्नोति, **अलोऽन्त्यस्येति** वचनादृकारस्य ॥

(उद्द्योतः) (वार्तिके) **नियमादिति** । **अलोऽन्त्यपरि**भाषायाः पूर्वाचार्यसंज्ञा नियम इति ॥ **तेनैव तस्यायुक्त इति** । स्वाङ्गेन स्वस्येत्यर्थः । शेषशेषिणोरभेदं मत्वा 'तेनैव' इत्याद्युक्तम् ॥ नन्वङ्गस्येति स्थानषष्ठीदर्शनात्सार्वधातुकेत्यादावन्त्यकोऽन्त्यपरिभाषाप्रवृत्त्या कथमिक्परिभाषायाश्रयणमित्यवकाशोऽत्र आह—अलो-

ऽन्त्येति । अनेकोऽनेको विशेषणेन पुगन्तेत्यादिनियमेन च तत्प्रयोजनसिद्धेरिति भावः ॥ अत्राहुरिति । अथवा विशेषिताऽनेको विशेषणसंभवात्प्रापयति । गावावित्यादि स्वेव न जानातीति भावः ॥

(विप्रतिषेधबाधकभाष्यम्)

नैष युक्तो विप्रतिषेधः । "विप्रतिषेधे परम्" इत्युच्यते । पूर्वश्चायं योगः, परो नियमः ॥

(प्रदीपः) **नैष युक्त इति** । इष्टसिद्धये इत्यर्थः । यथोद्देशपक्षे च परिभाषयोः पौर्वापर्यम्, न तु कार्यकालतायाम् ॥

(उद्योतः) **इष्टेति** । इष्टसिद्धिफलकत्वमेव हि तस्य युक्तत्वमिति भावः ॥ **न तु कार्येति** । द्वयोरप्येकदेशस्थत्वेन परत्वासंभवादिति भावः ॥ वस्तुतः कार्यकालपक्षेऽपि पाणिन्युच्चारणरूपपाठकृतं परत्वमस्त्येव । अन्यथैकत्र प्रयोगरूपदेशे सर्वेषां मेलनेन परत्वस्योच्छेद एव स्यात् । प्रयोगसाधनफलकान्येव शास्त्राणि । न चैवं कार्यकालपक्षमादाय त्रिपाद्यामेषां प्रवृत्तिर्यथोद्देशे तु पूर्वाण्येतानि प्रति त्रिपाद्या असिद्धत्वेनाप्रवृत्तिरेव स्यात्—इति भाष्याद्युक्तं विरुध्येतेति वाच्यम् । परिभाषायाः सिद्धत्वेन तत्पक्षेऽसिद्धेनापि कार्येण स्वार्थं तदाकर्षणसंभवादित्यष्टमे उपपादयिष्यमाणत्वात् । ध्वनितं चेदं सञ्जिस्थिति निर्दिष्ट इत्यत्र भाष्यकैयटयोरिति दिक्स्यमेतत् ॥

(विप्रतिषेधसाधकभाष्यम्)

इष्टवाची परशब्दः । विप्रतिषेधे परं यदिष्टं तद्भवतीति ॥

(विप्रतिषेधबाधकभाष्यम्)

एवमप्ययुक्तो विप्रतिषेधः । द्विकार्ययोगो हि विप्रतिषेधः । न चात्रैको द्विकार्ययुक्तः ॥

(प्रदीपः) **द्विकार्ययोग इति** । द्वाभ्यां कार्याभ्यां योगो यस्य स्थानिनः स विप्रतिषेधविषयत्वाद्विप्रतिषेधः ॥

(उद्योतः) ननु द्विकार्ययोग इत्यस्य द्वाभ्यां कार्याभ्यामन्यस्य योग इत्यर्थः, उत द्वयोः परस्परेण योग इत्यर्थः? उभयत्रापि त्रिपदतत्पुरुषो दुर्लभः । कर्मधारयपूर्वपदकोऽपि न, दिक्सङ्ख्ये इति नियमेन तस्य दुर्लभत्वादत आह—द्वाभ्यामित्यादि ॥ अत्रापि पक्षे विप्रतिषेधशब्देन सामानाधिकरण्यानुपपत्तेराह—विप्रतिषेधेति ॥

(विप्रतिषेधसाधकभाष्यम्)

नावश्यं द्विकार्ययोग एव विप्रतिषेधः ॥

किं तर्हि ?

असंभवोऽपि । स चास्त्यत्रासंभवः ॥

कोऽसावसंभवः ?

इह तावत्—'वृक्षेभ्यः-प्लक्षेभ्यः' इति एकः स्थानी, द्वावादेशौ, न चास्ति संभवः-यदेकस्य स्थानिनो द्वावादेशौ स्याताम् । इहेदानीं—'मेद्यति, मेद्यतः, मेद्यन्ति' इति द्वौ स्थानिनौ, एक आदेशः, न चास्ति संभवः—यत् द्वयोः स्थानिनोरेक आदेशः स्यादित्येषोऽसंभवः । सत्येतस्मिन्नसंभवे युक्तो विप्रतिषेधः ॥

(प्रदीपः) **नावश्यमिति** । द्विकार्ययोगत्वाभावे केवलोऽप्यसंभवो विप्रतिषेध इत्यर्थः ॥ **इह तावदिति** । दीर्घत्वं च यञ्यनन्तरे विधीयते, एत्त्वं झल्यनन्तरे । न च संभवोऽस्ति यत् द्वयोः स्वेन स्वेन निमित्तेनानन्तर्यं स्यात् ॥ **इहेदानीमिति** । मिदेरित्येका षष्ठी सा यद्यवयवसंबद्धा तदेकारस्य गुणेन भाव्यम्, अथ स्थानषष्ठी **तदाऽलोऽन्त्यस्येति** वचनादिकारस्येति । न चास्ति संभवो युगपदुभयोर्गुणस्येत्यर्थः ॥

(उद्योतः) द्विकार्ययोगेऽप्यसंभवसत्त्वादाह—**केवलोऽपीति** । ननु 'आ-ए' इति 'ए-आ' इति वाऽऽदेशसंभवोऽस्त्येवेत्यत आह—**नेति** ॥ **द्वयोरिति** । कार्ययोरित्यर्थः । अनन्तरे यञि दीर्घः साधुरनन्तरे झलि एत्त्वं साधुरित्यर्थ इति भावः ॥ **आद्गुण** इत्यादौ द्वयोः स्थानिनोरेकादेशस्य संभवादाह—**मिदेरिति** ॥ **न चास्ति संभवो युगपदिति** । युगपद्वाक्यार्थद्वयबोधाभावादिति भावः ॥

(विप्रतिषेधबाधकभाष्यम्)

एवमप्ययुक्तो विप्रतिषेधः । द्वयोर्हि सावकाशयोः समवस्थितयोर्विप्रतिषेधो भवति । अनवकाशश्चायं योगः ॥

(विप्रतिषेधोपपादनस्मरणभाष्यम्)

ननु च—इदानीमेवास्यावकाशः प्रक्लृप्तः—चयनं चायको लवनं लावक इति ॥

(विप्रतिषेधबाधकभाष्यम्)

अत्रापि नियमः प्राप्नोति । नाप्राप्ते नियमेऽयं योग आरभ्यते । यावता च नाप्राप्ते नियमेऽयं योग आरभ्यते, ततस्तदपवादोऽयं योगो भवति । उत्सर्गापवादयोश्चायुक्तो विप्रतिषेधः ॥

अथापि कथञ्चित् "इको गुणवृद्धी" इत्यस्यावकाशः स्यात् । एवमपि यथेह विप्रतिषेधादिको गुणो भवति-मेद्यति-मेद्यतः-मेद्यन्ति-इति, एवमिहापि स्यात्—अनेनिजुः-पर्यवेविषुरिति ॥

(प्रदीपः) **एवमपीति** । यदीदं नारभ्येत गुणवृद्धी कस्य स्याताम्? **अलोऽन्त्यस्येति** चेत्, **येन नाप्राप्तिन्यायेन** तस्यापवादत्वाद्विप्रतिषेधानुपपत्तिरित्यर्थः । एवं च क्रोष्ट्रीयमतं असंबद्धपरिभाषान्तरपक्षश्च नोपपद्यते ॥

(उद्योतः) ननु उक्तरीत्या प्रयोजनाभावादलोऽन्त्यस्याप्रवृत्तौ "अत्रापि नियमः प्राप्नोति" इत्यसङ्गतमित्यत आह—**यदीदमिति** । एतदभावे संभवति सामानाधिकरण्ये वैयधिकरण्यस्यान्याय्यत्वात्सर्वत्राङ्गस्येति स्थानषष्ठ्येव । कृते त्वस्मिन्नवयवषष्ठी सेति भावः ॥ **अथापि कथंचिदिति** भाष्यस्य—उक्त एवाशयः । **क्रोष्ट्रीयमतं**—विप्रतिषेधः । असंबद्धपरिभाषापक्षश्च तदुपजीव्यः । तेन्त्र विप्रतिषेधरहितोऽन्त्यस्त्वयुक्त एव । क्व संनिपातः क्वान्यतरत्यागः स च कस्येत्यत्र विनिग-

मकाभावेन सर्वेष्टासिद्धेः । तस्माद् द्वयमप्येकपक्षभूतमेव बोध्यम् ॥

(इत्यसंबद्धपरिभाषापक्षनिरासाधिकरणम् ॥)

(अथ सिद्धान्तभूतपदोपस्थितिपक्षनिरूपणम्)

(सिद्धान्तिभाष्यम्)

एवं तर्हि—वृद्धिर्भवति गुणो भवतीति यत्र ब्रूयात् 'इकः' इत्येतत्तत्रोपस्थितं द्रष्टव्यम् ॥

किं कृतं भवति ?

द्वितीया षष्ठी प्रादुर्भाव्यते ॥ तत्र कामचारः—गृह्यमाणेन वेकं विशेषयितुम्, इका वा गृह्यमाणम् । यावता कामचारः, इह तावन्मिदिमृजिपुगन्तलघूपधर्छिदृशिक्षिप्रक्षुद्रेषु गृह्यमाणेनेकं विशेषयिष्यामः—एतेषां य इगिति । इहेदानीं जुसिसार्वधातुकार्धधातुकह्रस्वाद्योर्गुणेष्विका गृह्यमाणं विशेषयिष्यामः—एतेषां गुणो भवति 'इकः' इगन्तानामिति ॥

(प्रदीपः) एवं तर्हीति । प्रदेशार्थत्वादनयोः परिभाषयोर्गुणत्वात्परस्परेण संबन्धाभावात् प्रदेशवाक्यपर्यालोचनया वाक्यार्थस्यावस्थानमित्यर्थः ॥

(उद्योतः) प्रदेशार्थत्वादिति । परस्परेण संबन्धाभावादित्यन्तेन तच्छेषत्वासंभव उक्तः । पदोपस्थितिपक्षे च विधेयसमर्पकत्वेन गृहीतगुणादिपदश्रुतिरस्या लिङ्गमित्येषाऽन्तरङ्गा । तत्त्वेन ग्रहश्च प्रथमाया विधेयविभक्तित्वेन तदन्तत्वेन पदज्ञानकाल एव । तदुक्तं भाष्ये—गुणो भवतीति यत्रेत्यादि ॥ नियमस्तु स्थानषष्ठीलिङ्गक इति अवान्तरवाक्यार्थबोधोत्तरकालिकत्वेन बहिरङ्गः ॥ एवं च मिदादावुपस्थितेक्परिभाषायाः सामानाधिकरण्यासंभवाद्वैयधिकरण्यान्वये वृत्ते निमित्ताभावादेवालोऽन्त्यस्येत्यस्यानुपस्थितिः । सार्वधातुकार्धधातुकयोरित्यादौ सामानाधिकरण्यान्वयेऽलोन्त्यस्येत्यनेनान्त्यस्यादेशव्यवस्था ॥ एतेनैकस्या अप्रवृत्तौ अपराऽपि न प्रवर्तेतेत्यपास्तम् ॥ पर्यालोचनयेति । प्रदेशे सति संभवे परिभाषाद्वयैकवाक्यतया वाक्यार्थः । अन्यथा त्विक्परिभाषागर्भ एव, अस्या अन्तरङ्गत्वादित्यर्थः ॥

भाष्ये—वृद्धिर्भवतीत्यादि । इतिशब्दो यत्रेत्यर्थः ॥ इक इत्येतदिति । सूत्रे 'इकः' इति षष्ठ्यन्तानुकरणमित्यर्थः ॥ अनुवृत्तस्य स्वरूपपरत्वेन गुणशब्दो भवतीत्याद्यर्थः स्यादतः पुनरत्र गुणवृद्धिग्रहणम् । अनुवृत्तस्यार्थपरत्वं तु न, शब्दाधिकारापत्तेः । उभाभ्यां च गुणशब्दवान् गुणो यत्रेत्यादिरर्थः । तदुक्तं—इति यत्रेत्यादि । गुणपदं यत्र वर्तते इत्याद्यर्थस्तु न, अतो गुण इत्यादावव्याप्तेः । भवतिक्रियाया अन्तरङ्गत्वाच्च । अस्मादेव गुणवृद्धिग्रहणादत्र 'विधीयते' इत्यस्य तदर्थकस्य भवतीत्यस्य वाऽध्याहार इति । एतन्मूलकमेवानुवादे परिभाषा नोपतिष्ठते इति । अत एव तत्–एतद्विषयमेव, अचश्चेत्येतद्विषयमेव च । अचोऽञ्णितीत्यादौ तु वाक्यार्थबोधकाले श्रौताच्पदेनैवाकाङ्क्षाशान्तौ लिङ्गोपस्थितस्य दुर्बलतयाऽनन्वय इति दिक् ॥

(तच्छेषपक्षोक्तदूषणनिराकरणभाष्यम्)

अथवा सर्वत्रैवात्र स्थानी निर्दिश्यते । इह तावत् मिदेः–'इत्यविभक्तिको निर्देशः—मिद् एः–मिदेः, मिदेरिति ॥ अथवा षष्ठीसमासो भविष्यति—मिद इः–मिदिः, मिदेरिति ॥

पुगन्तलघूपधस्येति नैवं विज्ञायते—पुगन्ताङ्गस्य लघूपधस्य चेति ।

कथं तर्हि ?

पुकि अन्तः पुगन्तः, लघ्वी उपधा लघूपधा, पुगन्तश्च लघूपधा च पुगन्तलघूपधम्, पुगन्तलघूपधस्येति । अवश्यं चैतदेव विज्ञेयम्, अङ्गविशेषणे हि सतीह प्रसज्येत-भिनत्ति, छिनत्तीति ॥

ऋच्छेरपि प्रश्लिष्टनिर्देशोऽयम्—ऋच्छति-ऋ-ऋृताम्-"ऋच्छत्यृताम्" इति ॥

दृशेरपि योगविभागः करिष्यते—"उरङि गुणः" उः अङि गुणो भवति । ततो "दृशेः" दृशेश्चाङि गुणो भवति । उरित्येव ॥

क्षिप्रक्षुद्रयोरपि "यणादिपरं गुणः" इतीयता सिद्धम् । सोऽयमेवं सिद्धे सति यत्पूर्वग्रहणं करोति तस्यैतत्प्रयोजनम्—इको यथा स्यादनिको मा भूदिति ॥

(प्रदीपः) अथवेति । तच्छेषपक्षोक्तदोषपरिहारः । क्षिप्रक्षुद्रयोरपीति । अत्र च योगविभागः क्रियते—स्थूलादीनां यणादिपरं लुप्यते, ततः-पूर्वस्य च गुण इति । अत्र च स्वरितत्वात् क्षिप्रक्षुद्रावेवानुवर्तेते, स्थूलादयो निवृत्ताः, तेषां तु यणादिलोपे सति 'ओर्गुणः' इति गुणो भवति । असिद्धवदत्राभादित्यसिद्धत्वमनित्यत्वान्न भवति । तत्र क्षिप्रक्षुद्रयोर्यण आदिः पकारो दकारश्च, तस्माद्यणादेः परं लुप्यते तस्मादेव च यणादेः पूर्वस्य च गुण इति सिद्धम्—क्षेपिष्ठः क्षोदिष्ठ इति ॥ 'यणादिपरं'इति पञ्चमीसमासः ॥ यदि तर्हि 'पुगन्तलघूपधस्य' इति स्थानी निर्दिश्यते तच्छेषपक्षाश्रयणाच्चात्रेक्परिभाषा नोपतिष्ठते तदाऽस्य गुणस्यानिग्लक्षणत्वात् भिन्नमित्यादौ 'क्ङिति च' इति निषेधो न प्राप्नोति । यथा-लैगवायन इति ॥ नैष दोषः, क्नुसनोः कित्त्वविधानात् ज्ञापकादनिग्लक्षणत्वेऽपि लघूपधगुणस्य प्रतिषेधो भविष्यति ॥

(उद्योतः) (भाष्ये) पुकि अन्त इति । सुप्सुपेति समासः । भिनत्तीत्यत्र गुणापादनं क्ङितीत्यस्य निमित्तसप्तमीत्वात् । इकः सार्वधातुकार्धधातुकयोरिति विशेषणमिति तु न युक्तम्, तस्याङ्गांशे उत्थिताकाङ्क्षत्वात् ॥ भाष्ये–यणादिपरं गुण इति । यणादिपरं लुप्यतेऽवशिष्टस्य गुण इत्यर्थेन क्षिप्रादेः सर्वादेशो गुणः सिद्धः । स्थूलादौ तु ओर्गुण इत्येव सिद्धमिति भावः ॥ ननु पूर्वस्येत्युक्तावपि 'यणपेक्षादेः परं' इत्यर्थे पूर्वस्य गुण इत्यनेनापि तत एव पूर्वस्य गुणापत्तौ स्थूलादिषु थकारादेर्गुणः स्यात् । यण् आदिर्यस्य तद्रूपं परं लुप्यते ततः पूर्वस्य च गुण इत्यर्थे क्षिप्रक्षुद्रयोरन्त्यस्य व्यञ्जनस्य गुणः स्यादत आह—अत्र चेति ॥ अनित्यत्वादिति । आसन्नित्यत्र लोपनिवृत्त्यर्थात् असोरल्लोप इति तपरकरणादित्यर्थः ।

तथा हि—अस् अन्तीति स्थिते परत्वादल्लोपे तस्यासिद्धत्वात्पुनः प्रसङ्गेनाटि विकारान्यानुपूर्व्यैक्याभावेन लक्ष्ये लक्षणस्येति न्यायाप्राप्तौ प्राप्तलोपवारणार्थं तपरत्वमाटोऽसिद्धत्वे व्यर्थं सत्तदनित्यत्वे ज्ञापकम् । न चाटोऽप्यनापत्तिः, तत्रानित्यत्वे मानाभावात् ॥ तस्मादेव चेति । पूर्वत्वस्यावध्याकाङ्क्षायां परत्वेऽवधित्वेन श्रुतत्वादुपस्थितत्वाच्च तस्यैवावधित्वमिति भावः ॥ तद्ध्वनयन्व्याचष्टे—पञ्चमीसमास इति । सुप्सुपेत्यनेन । अवयवभूते यणादीत्यत्र समुदिते चेत्यर्थः । न चैवं हस्तशब्दे रस्तशब्दस्यापि लोपापत्तिः, स्थूलादिसाहचर्येणोपान्त्ययणादेः परस्यैव लोपादित्याहुः ॥ पक्षाश्रयणाच्चेति । परिभाषाणामनियमे नियमकारिणीत्वाच्चेत्यपि बोध्यम् । एवं 'क्ष्मापयति' इत्यादौ पुगन्तेति गुणे उपधावृद्धिरिति न दोषः ॥ क्नुसनोरिति । एतात्क्क्ङिति चेति सूत्रे उपपादयिष्यते ॥

(वृद्धिपदप्रयोजनाधिकरणम्)

(आक्षेपभाष्यम्)

अथ वृद्धिग्रहणं किमर्थम् ?

(उद्द्योतः) भाष्ये शङ्कते—अथ वृद्धिग्रहणमिति ॥

(प्रत्याक्षेपभाष्यम्)

किं विशेषेण वृद्धिग्रहणं चोद्यते, न पुनर्गुणग्रहणमपि । यदि किंचिद्गुणग्रहणस्य प्रयोजनमस्ति, वृद्धिग्रहणस्यापि तद्भवितुमर्हति । को वा विशेषः ?

(प्रत्याक्षेपसमाधानभाष्यम्)

अयमस्ति विशेषः—गुणविधौ न कश्चित्स्थानी निर्दिश्यते, तत्रावश्यं स्थानिनिर्देशार्थं गुणग्रहणं कर्तव्यम् । वृद्धिविधौ पुनः सर्वत्रैव स्थानी निर्दिश्यते—"अचो ञ्णिति" "अत उपधायाः" "तद्धितेष्वचामादेः" इति ॥

(प्रदीपः) **गुणविधाविति** । कश्चिन्न निर्दिश्यत इति नञो व्यवहितेन संबन्धः । कश्चिद्धि निर्दिश्यत एव—**ओर्गुण** इत्यादौ ॥

(उद्द्योतः) 'न कश्चित्स्थानी निर्दिश्यते' इत्युक्त्या—सर्वत्रैव न निर्दिश्यते—इति प्रतीयते, कश्चिदादिपदभाष्यार्थिकमः कश्चिदादिपदबोध्याधिकरणादौ सर्वत्राभावप्रतीतेर्व्युत्पत्तिसिद्धत्वात् । तद्युक्तमत आह—कश्चिदिति ॥

(समाधानभाष्यम्)

अत उत्तरं पठति—

(८० सिद्धान्तिसमाधानवार्तिकम् ॥ १ ॥)

॥ * ॥ वृद्धिग्रहणमुत्तरार्थम् ॥ * ॥

(भाष्यम्)

वृद्धिग्रहणं क्रियते । किमर्थम् ? उत्तरार्थम् । "क्ङिति" इति प्रतिषेधं वक्ष्यति, स वृद्धेरपि यथा स्यात् ॥

(उद्द्योतः) भाष्ये सिद्धान्त्याह—वृद्धिग्रहणमुत्तरार्थमिति ॥

(पूर्वपक्षिण आक्षेपभाष्यम्)

कथेदानीं क्रित्प्रत्ययेषु वृद्धेः प्रसङ्गः । यावता "ञ्णिति" इत्युच्यते ?

(उद्द्योतः) पूर्वपक्ष्याह—कथेत्यादि ॥

(वृद्धिग्रहणप्रयोजनभाष्यम्)

तत्र मृज्यर्थम् ।

(भाष्यम्)

मृजेर्वृद्धिरविशेषेणोच्यते । सा क्ङिति मा भूत्—मृष्टः-मृष्टवानिति ॥

(उद्द्योतः) अविशेषेणोच्यते । सा क्ङितीति । प्रत्ययविशेषानाश्रयणमत्राविशेषः

(प्रयोजनभाष्यम्)

इहार्थं चापि

मृज्यर्थं वृद्धिग्रहणं कर्तव्यम् । मृजेर्वृद्धिरविशेषेणोच्यते । सेको यथा स्यात्, अनिको मा भूदिति ॥

(प्रदीपः) **मृजेर्वृद्धिरिति** । तत्र हि सूत्रेऽभिमतस्थान्यनुपादानादलोऽन्त्यपरिभाषयाऽन्त्यस्यैव स्यादित्यर्थः ॥

(उद्द्योतः) उत्तरस्याविशेषेणेत्यस्य स्थानिविशेषानुच्चारणेनेत्यर्थः । तदाह—तत्र हि सूत्र इति ॥

(प्रयोजननिरसनभाष्यवार्तिकम्)

मृज्यर्थमिति चेद्योगविभागात्सिद्धम्

(भाष्यम्)

मृज्यर्थमिति चेद्योगविभागः करिष्यते—"मृजेर्वृद्धिरचः" । ततः—"ञ्णिति" ञिति णिति च वृद्धिर्भवति, 'अचः' इत्येव ॥

(आक्षेपभाष्यम्)

यद्यचो वृद्धिरुच्यते, 'न्यमार्ट्' अटोऽपि वृद्धिः प्राप्नोति ॥

(प्रदीपः) **अटोऽपीति** । नन्वडागमात्पूर्वमेव परत्वाद्वृद्धिर्भविष्यति, लक्षणस्य च प्रवृत्तत्वादटि कृते पुनर्लक्षणं न प्रवर्तिष्यते ॥ एवं तर्हि विप्रतिषेधानपेक्षयैवात्र चोद्यपरिहारावुक्तौ ॥

(उद्द्योतः) अडागमात्पूर्वमिति । लादेशेषु कृतेष्वडिति पक्षे—इदम् ॥ अटि कृते इति । विकारान्यानुपूर्व्या भेदेन लक्ष्यभेदाच्चिन्त्यमिदम् । परत्वादित्यपि चिन्त्यं, द्वयोर्यौगपद्यासंभवात् ॥ एवं तर्हीति । लावस्थायामडिति पक्षे—इति भावः ॥

(एकदेशिनः समाधानभाष्यम्)

अटि चोक्तम्

किमुक्तम् ?

'अनन्त्यविकारेऽन्त्यसदेशस्य कार्यं भवति'

इति ॥

(उद्योतः) भाष्ये—अनन्त्यविकारे इति । तयाऽपि सिध्यतीत्यभिमानः ॥ सिद्धान्ते त्वन्यार्थमिग्ग्रहणे कृते तेनैवाटो व्यावृत्तिसिद्धौ सा नैतदर्थेति व्यङ इति सूत्रे वक्ष्यत इति न विरोधः ॥

(८१ सिद्धान्तवार्तिकम् ॥ २ ॥)

॥ * ॥ वृद्धिप्रतिषेधानुपपत्तिस्त्विक्प्रकरणात् ॥ * ॥

(भाष्यम्)

वृद्धेस्तु प्रतिषेधो नोपपद्यते ।

किं कारणम् ?

इक्प्रकरणात् । इग्लक्षणयोर्गुणवृद्ध्योः प्रतिषेधः । न चैवं सति मृजेरिग्लक्षणा वृद्धिर्भवति । तस्मान्मृजेरिग्लक्षणा वृद्धिरेषितव्या ॥

(उद्योतः) तस्मान्मृजेरिगिति । निषेधस्य सिद्धये योगविभागमकृत्वा स्थानिसमर्पणायास्या ऽप्योपस्थितिरङ्गीकार्येति भावः ॥

(इक्परिभाषानुपस्थितिसूचकभाष्यम्)

एवं तर्हि—इहान्ये वैयाकरणा मृजेरजादौ संक्रमे विभाषा वृद्धिमारभन्ते—परिमृजन्ति, परिमार्जन्ति, परिममृजतुः, परिममार्जतुः—इत्याद्यर्थम् । तदिहापि साध्यम् । तस्मिन् साध्ये योगविभागः करिष्यते—"मृजेर्वृद्धिरचः" भवति ॥

ततः—"अचि क्ङिति" अजादौ च क्ङिति मृजेर्वृद्धिर्भवति । परिमार्जन्ति, परिमार्जन्तु ।

किमर्थमिदम् ?

नियमार्थम्-अजादावेव क्ङिति, नान्यत्र ।

कान्यत्र मा भूत् ?

मृष्टः, मृष्टवानिति ।

ततः—"वा", वाऽचि क्ङिति मृजेर्वृद्धिर्भवति । परिमृजन्ति, परिमार्जन्ति, परिममृजतुः, परिममार्जतुरिति ॥

(उद्योतः) संक्रम इति । गुणवृद्धिप्रतिषेधविषयक्ङितः प्राचां संज्ञा । 'अचि' इत्येव वचनम् । 'आदौ' इति तु तदादिपरिभाषालब्धार्थानुवादः । अत एवाग्रे वक्ष्यति—ततोऽचि क्ङितीति । एवं च 'ममृजे-यूयं ममृज' इत्यादौ विकल्पो भवत्येव ॥ एतेनादिग्रहणसामर्थ्यान्मुख्याजादावेव प्रवृत्तिः, तेन पूर्वोदाहृतेषु न वृद्धिरिति हरदत्तोक्तमपास्तम् ॥ तुन्दपरिमृज इत्यत्र यदि वृद्ध्यभाव इष्टस्तर्हि व्यवस्थितविभाषया नेति बोध्यम् ॥ अजादावेवेति । विपरीतनियमस्तु न, इष्टानुरोधात् ॥

(प्रयोजनान्तरसूचकभाष्यम्)

इहार्थमेव तर्हि सिजर्थं वृद्धिग्रहणं कर्तव्यम् । सिचि वृद्धिरविशेषेणोच्यते, सेको यथा स्यात्, अनिको मा भूदिति ॥

(उद्योतः) सिचि वृद्धौ स्थानिविशेषानाश्रयणरूपोऽविशेषः । उत्तरार्धत्वे खण्डिते सिद्धान्त्याह—इहार्थमेवेति ॥

(प्रयोजनाक्षेपभाष्यम्)

कस्य पुनरनिकः प्राप्नोति ?

(उद्योतः) तत् स्फुटयति पूर्वपक्षी—कस्य पुनरित्यादि ॥

(समाधानभाष्यम्)

अकारस्य । अचिकीर्षीत्, अजिहीर्षीत् ॥

(प्रत्याक्षेपभाष्यम्)

नैतदस्ति । लोपोऽत्र बाधको भविष्यति ॥

(प्रदीपः) अचिकीर्षीदिति । पूर्वविप्रतिषेधादतो लोपः, यथा-चिकीर्षक इति ॥

(उद्योतः) पूर्वविप्रतिषेधेति । ण्यल्लोपावियङ्यिण्वद्भ्योः पूर्वविप्रतिषेधेनेत्यादिः ॥ चिकीर्षक इति।अन्यथा अत्र परत्वाद्वृद्धौ युकि चिकीर्षायक इति स्यात्॥

(प्रयोजनभाष्यम्)

आकारस्य तर्हि प्राप्नोति—अयासीत्, अवासीत् ।

(प्रयोजनाक्षेपभाष्यम्)

नास्त्यत्र विशेषः, सत्यां वृद्धावसत्यां वा ॥

(प्रदीपः) अयासीदिति । परत्वादत्र सगिटोः कृतयोरनन्त्यत्वादाकारस्य नास्ति वृद्धिप्रसङ्ग इति यद्यपि परिहारोऽस्ति, तथापि विशेषाभावेन परिहृतत्वान्नायमाश्रितः ॥

(उद्योतः) परत्वादत्रेति । अपवादत्वादित्यर्थः । परशब्द उत्कृष्टवाची ॥

(समाधानभाष्यम्)

संध्यक्षरस्य तर्हि प्राप्नोति ॥

नैव संध्यक्षरमन्त्यमस्ति ॥

(उद्योतः) भाष्ये—नैव सन्ध्यक्षरमिति । वृद्धियोग्यमिति शेषः । उपदेश आत्त्वविधानादिति भावः ॥ अन्त्यमिति । अङ्गस्य वृद्धिरित्यर्थेऽलोन्त्यपरिभाषाप्रवृत्तेरिति भावः ॥

(उदाहरणभाष्यम्)

ननु चेदमस्ति—ढलोपे कृते-उदवोढाम्, उदवोढम्, उदवोढेति ॥

नैतदस्ति । असिद्धो ढलोपः, तस्यासिद्धत्वान्नैतदन्त्यं भवति ॥

(प्रदीपः) उदवोढामिति । ढलोपादीनामसिद्धत्वात्पूर्वं हलन्तलक्षणा वृद्धिः, ततो ढलोपादिषु कृतेषु ढलोपस्यासिद्धत्वादोकारस्य न भविष्यति ॥ गोशब्दादाचारे क्विपि अगवीदिति संध्यक्षरमन्त्यमस्ति तस्य कस्माद्वृद्धिर्न भवति ? उच्यते—'सिचि वृद्धिः-' इत्यत्र धातुग्रहणं 'ऋत इद्धातोः' इत्यत औपदेशिकधातुपरिग्रहार्थमनुवर्तत इत्यदोषः ॥

(उद्योतः) ढलोपस्यासिद्धत्वादिति । पूर्वं हलन्तलक्षणाया वृद्धेर्जातत्वेनेदानीं सिचि वृद्धिरित्यस्य प्राप्त्या लक्ष्ये लक्षणस्याप्रवृत्तिरिति भावः ॥ धातुग्रहणमिति । सिचा तदाक्षेपे सिद्धे-इति भावः ॥ एवञ्च कव्यादिभ्य आचारक्विपि अकवायीदित्यादौ वृद्धिर्नेति लक्ष्यते ॥ माधवस्तु वृद्धिं मनुते । बहुलं छन्दसीत्यतो बहुलग्रहणानुवृत्त्या सन्ध्यक्षरान्तनामधातौ वृद्धिर्न, अन्यत्र भवत्येवेति तदाशयः ॥ तेन सेशब्दादिभ्य आचारक्विपि न वृद्धिरित्यलम् । वस्तुतस्तु नैव

सन्ध्यक्षरमिति पदगर्भितग्राम्यप्रामाण्येन सन्ध्यक्षरान्तेभ्य आचारक्विपेव नेत्याहुः ॥

(उदाहरणभाष्यम्)

व्यञ्जनस्य तर्हि प्राप्नोति-अभैत्सीत्, अच्छैत्सीत्॥ हलन्तलक्षणा वृद्धिर्बाधिका भविष्यति ॥

(उद्द्योतः) हलन्तलक्षणा वृद्धिर्बाधिकेति-भाष्ये । इग्ग्रहणाभावे येन नाप्राप्तिन्यायेनेति भावः ॥

(उदाहरणभाष्यम्)

यत्र तर्हि सा प्रतिषिध्यते—"नेटि" इति। अकोषीत्, अमोषीत् ॥

(उदाहरणाक्षेपभाष्यम्)

सिचिवृद्धेरप्येष प्रतिषेधः ।

कथम् ?

लक्षणं हि नाम ध्वनति भ्रमति मुहूर्तमपि नावतिष्ठते ॥

(प्रदीपः) **लक्षणं हीति** । **'नेटि'** इति लक्षणमविशेषेण वृद्धिमात्रस्य निषेधं कथयतीति 'ध्वनति' इत्युच्यते । यो ह्यव्यक्तं कथयति स ध्वनतीत्युच्यते । एवमिहाप्यस्या एव वृद्धेर्निषेध इति नास्ति व्यक्तिः ॥ स्यादेतत्—एकनिषेधे चरितार्थत्वात्पुनः प्रतिषेध्यान्तरे प्रवृत्तिर्न स्यादित्याह—**भ्रमतीति** । सर्वत्र व्याप्रियत इत्यर्थः । स्यादेतत्—यावदेकनिषेध्येऽस्य व्यापारस्तावदेव द्वितीयो विधिः प्रवृत्तः, प्रवृत्तस्य च निषेधोऽशक्यः कर्तुमित्याह—**मुहूर्तमिति** । उभयत्रापि व्यापाराद्येकत्र विश्राम्यतीत्यर्थः ॥

(उद्द्योतः) **इत्याहेति** । इत्याशङ्कायामाहेत्यर्थः ॥ **नैकत्रेति** । बाध्यसामान्यचिन्तेयम् । नेटीत्यत्र हलन्तस्येत्यप्यनुवर्त्य हलन्तस्य या वृद्धिः प्राप्ता सा सर्वाऽपि नेत्यर्थः । तेनालावीदित्यादौ न दोष इति बोध्यम् ॥

(आक्षेपे प्रकारविशेषभाष्यम्)

अथवा "सिचि वृद्धिः परस्मैपदेषु" इति सिचि वृद्धिः प्राप्नोति। तस्या हलन्तलक्षणा वृद्धिर्बाधिका। तस्या अपि "नेटि" इति प्रतिषेधः॥

(प्रदीपः) **तस्या अपीति** । अपिशब्दात्सिचि वृद्धेरपि ॥

(उद्द्योतः) बाध्यविशेषचिन्तायामाह—भाष्ये—**अथवेति** । तद्याचष्टे—**अपिशब्दादिति** ॥

(दृष्टान्ताक्षेपभाष्यम्)

अस्ति पुनः क्वचिदन्यत्रापि अपवादे प्रतिषिद्धे उत्सर्गोऽपि न भवति ?

(उद्द्योतः) स्वप्रतिषेध्यहलन्तलक्षणवृद्धिप्रतिषेधद्वारा **अष्टावसरन्यायेन सिचि वृद्धेरप्यभावः** प्रतिपाद्यते इत्यर्थः । तद्ध्वनयन्नाह—भाष्ये—**अस्ति पुनः क्वचिदित्यादि** ॥

(दृष्टान्तभाष्यम्)

अस्तीत्याह । सुजाते अश्वसूनृते, अध्वर्यो अद्रिभिः सुतम्, शुक्रं ते अन्यद्-इति पूर्वरूपत्वे प्रतिषिद्धेऽयादयोऽपि न भवन्ति ॥

(प्रदीपः) **अस्तीत्याहेति** । **'नान्तःपादमव्यपरे'** इति पाठमाश्रित्यैतदुक्तम् ॥ यद्येवं वृक्षावित्यत्र **'नादिचि'** इत्यनेन पूर्वसवर्णदीर्घे निषिद्धे वृद्धेरपि प्रतिषेधप्रसङ्गः । नैष दोषः, **'संघोद्वौ-'** इत्यादेर्ज्ञापकादनन्तरस्यैव **'नादिचि'** इति प्रतिषेधात् ॥

(उद्द्योतः) ननु तत्र प्रकृतिभावेन साक्षादेवोत्सर्गापवादयोर्निवृत्तिः, न त्वपवादेन बाधादुत्सर्गस्येत्यत आह—**नाम्न इति** ॥ भाष्ये—**न भवन्तीति** । अष्टावसरन्यायेनेति भावः ॥ **पूर्वसवर्णदीर्घवद्वृद्धेरपीति** । अवर्णादिचि यद्यत्प्राप्तं तन्नेति बाध्यसामान्यचिन्तारूपाद्यपेक्षेणेयं शङ्का ॥ ज्ञापकाद्बाध्यविशेषचिन्तैवाश्रीयते इत्युत्तरम् ॥ **पूर्वसवर्णदीर्घे निषिद्धे वृद्धेरपीति** । पाठे अष्टावसरन्यायानित्यत्वेन क्वचिदपवादनिवृत्तावपि तद्विषये उत्सर्गप्रवृत्तिर्ज्ञाप्यते इति भावः ॥

परे तु 'अथवा' इति भाष्यं पूर्वपक्ष्युक्तिलात्प्रौढ्या । अष्टावसरन्यायस्तु नास्त्येव, उक्तनिर्देशात् । अत एव नान्तःपादमिति सूत्रे एङोऽतीत्यनुवर्त्य एङोऽति यद्यत्प्राप्नोति तस्य निषेध इत्यर्थमाश्रित्य सर्वनिषेधकत्वं तस्योक्तमिति वदन्ति ॥

(सिद्धान्तिनः प्रयोजनभाष्यम्)

उत्तरार्थमेव तर्हि सिज्ग्रहणं वृद्धिग्रहणं कर्तव्यम्। सिचि वृद्धिरविशेषेणोच्यते, सा क्ङिति मा भूत्—न्यनुवीत्, न्यधुवीत् ॥

(उद्द्योतः) इहार्थत्वे पूर्वपक्षिणा द्वेधा प्रौढ्याऽपि खण्डिते सिद्धान्ती तदभ्युपेत्याप्याह—**उत्तरार्थमेवेति** ॥ णुधूञ् तू कुटादी ॥

(प्रयोजननिरासभाष्यम्)

नैतदस्ति प्रयोजनम्। अन्तरङ्गत्वादत्रोवङादेशे कृतेऽनन्त्यत्वाद्वृद्धिर्न भविष्यति ॥

(प्रदीपः) **अन्तरङ्गत्वादिति** । उवङादेशः सिचमेवापेक्षते, वृद्धिस्तु सिच्परस्मैपदे ॥

(उद्द्योतः) भाष्ये—**अनन्त्यत्वादिति** । अचोऽनन्त्यत्वादित्यर्थः ॥ नन्विकपरिभाषाभावेऽन्त्यस्यमात्रस्य सा प्राप्नोतीति **अनन्त्यत्वादित्यसङ्गतमिति चेत्** । न, हलन्तेषु हलन्तलक्षणया बाधेनास्या वृद्धेरजन्त एव व्यवस्थितेरित्याशयात् ॥

(सिद्धान्तिभाष्यम्)

यदि तर्हि सिच्यन्तरङ्गं भवति—अकार्षीत्, अहार्षीत्, गुणे कृते रपरत्वे चानन्त्यत्वाद्वृद्धिर्न प्राप्नोति ॥

(उद्द्योतः) सिद्धान्त्याह—**यदि तर्हीति** ॥ अत्र यदीत्यनेनापवादत्वात्तद्विषयेऽन्तरङ्गप्रवृत्तिरेव वक्तुमशक्येति ध्वनितम् ॥ इत उत्तरग्रन्थस्तु सिद्धान्त्याशयानभिज्ञपूर्वपक्ष्येकदेशि-सिद्धान्त्येकदेशिनोरिति बोध्यम् ॥

(पूर्वपक्ष्येकदेशिनो भाष्यम्)

मा भूदेवम्। "हलन्तस्य-" इत्येवं भविष्यति ॥

(सिद्धान्त्येकदेशिनो दूषणभाष्यम्)

इह तर्हि—न्यस्तारीत्, न्यदारीत् । गुणे कृते रपरत्वे चानन्त्यत्वाद्वृद्धिर्न प्राप्नोति । हलन्तलक्षणायाश्च "नेटि" इति प्रतिषेधः ॥

(पूर्वपक्ष्येकदेशिनः समाधानभाष्यम्)

मा भूदेवम् । "ल्रान्तस्य" इत्येवं भविष्यति ॥

(सिद्धान्त्येकदेशिन आक्षेपभाष्यम्)

इह तर्हि—अलावीत्, अयावीत्—गुणे कृतेऽवादेशे चानन्त्यत्वाद्वृद्धिर्न प्राप्नोति । हलन्तलक्षणायाश्च 'नेटि' इति प्रतिषेधः ॥

(पूर्वपक्ष्येकदेशिनः समाधानभाष्यम्)

मा भूदेवम् । "ल्रान्तस्य" इत्येवं भविष्यति ॥

(सिद्धान्त्येकदेशिन आक्षेपभाष्यम्)

"ल्रान्तस्य" इत्युच्यते, न चेदं ल्रान्तम् ॥

(पूर्वपक्ष्येकदेशिनः समाधानभाष्यम्)

"ल्रान्तस्य" इत्यत्र वकारोऽपि निर्दिश्यते ।

(सिद्धान्त्येकदेशिन आक्षेपभाष्यम्)

किं वकारो न श्रूयते ?

(पूर्वपक्ष्येकदेशिनः समाधानभाष्यम्)

लुप्तनिर्दिष्टो वकारः ॥

(प्रदीपः) लुप्तनिर्दिष्ट इति । 'लोपो व्योर्वलि' इति भावः ॥ किमत्र प्रमाणमिति चेत्, अभियुक्तस्मरणमेव ॥

(उद्द्योतः) लुप्तनिर्दिष्ट इत्यत्र पूर्वं निर्दिष्टः पश्चाल्लुप्त इत्यर्थे मयूरव्यंसकादित्वात्समासः । न च गुणे वार्णादाङ्गमिति न्यायेन-अवं बाधित्वा वृद्धौ-आवादेशेऽलावीदित्यादेः सिद्धौ वप्रश्लेषो व्यर्थ इति वाच्यम् । सिचि वृद्धिरित्यस्यापवादत्वाज्ज्ञानेनैव एतत्परिभाषाज्ञानेनैवास्य प्रवृत्तेरलोपात् । न च वकारप्रश्लेषेऽलवीदलावीदिति वकारान्तोऽनिलक्ष्यापत्तिः । अस्या एकदेशस्युक्तित्वेन तदज्ञानेनैवास्य भाष्यस्य प्रवृत्तेः, जिरिवियोपज्ञानवत्—इत्याहुः ॥ एतद्भाष्यप्रामाण्यादस्य धातुः पर्यायान्तो वयोः समानश्रुतित्वाल्लोके दन्त्योष्ठ्यवर्णितिरित्यन्ये ॥

(सिद्धान्त्येकदेशिनो दूषणभाष्यम्)

यद्येवम्—मा भवानवीत्, मा भवान् मवीत् —अत्रापि प्राप्नोति ॥

(उद्द्योतः) अवेरादि वृद्ध्यवृद्ध्योरविशेष इति आदनिवृत्तये भाष्ये माङ् प्रयुक्तः । एकादेशे पुनरप्यविशेषस्तदवस्थ इति भवानित्युक्तं, मवौ तु प्रयोजनान्तराभावेऽप्यैकरूप्याय तत्प्रयोगः ॥

(पूर्वपक्ष्येकदेशिनः समाधानभाष्यम्)

अविमव्योर्नेति वक्ष्यामि ॥

(सिद्धान्त्येकदेशिन आक्षेपभाष्यम्)

तद्वक्तव्यम् ?

(पूर्वपक्ष्येकदेशिनः समाधानभाष्यम्)

न वक्तव्यम् । 'णिश्व्योः तौ निमातव्यौ' । यद्यप्येतदुच्यते, अथवैतर्हि णिश्व्योः प्रतिषेधो न वक्तव्यो भवति । गुणे कृतेऽयादेशे च यान्ताना नेत्येव प्रतिषेधो भविष्यति ॥

(प्रदीपः) णिश्व्योरयामिति । णिश्विग्रहणमकृत्वा-अविमवी प्रतिषेधार्थं कर्तव्यौ । एवं सति गौरवाभावः ॥ निमातव्याविति । मेळो रूपम् । परिवर्तनीयावित्यर्थः ॥

(उद्द्योतः) अविमव्योर्नेति निषेधश्च मध्येऽपवादन्यायेनातोल्रान्तस्येत्यस्यैव, तेनातो हलादेरिति विकल्पो भवत्येवेति बोध्यम् । सिचि वृद्धिरिति सूत्रं तु अचैषीदित्यादौ गुणे कृते चरितार्थमेतन्मते इति बोध्यम् ॥

(सिद्धान्त्येकदेशिनः पूर्वोक्तदोषवारणाय ज्ञापकभाष्यम्)

एवं तर्ह्याचार्यप्रवृत्तिर्ज्ञापयति—न सिच्यन्तरङ्गं भवति—इति । यदयं "अतो हलादेर्लघोः" इत्यकारग्रहणं करोति ।

कथं कृत्वा ज्ञापकम् ?

अकारग्रहणस्यैतत्प्रयोजनम्—इह मा भूत्—अकोषीत्, अमोषीत्, । यदि सिच्यन्तरङ्गं स्यात्, अकारग्रहणमनर्थकं स्यात् । गुणे कृतेऽलघुत्वाद्वृद्धिर्न भविष्यति । पश्यति त्वाचार्यः—'न सिच्यन्तरङ्गं भवति' इति । ततोऽकारग्रहणं करोति ॥

(पूर्वपक्ष्येकदेशिन आक्षेपभाष्यम्)

नैतदस्ति ज्ञापकम् । अस्त्यन्यदेतस्य वचने प्रयोजनम् ।

किम् ?

यत्र गुणः प्रतिषिध्यते तदर्थमेतत्स्यात् । न्यकुटीत्, न्युपुटीत्—इति ॥

(उद्द्योतः) (भाष्ये) नैतदस्ति ज्ञापकमिति । न्यकुटीदित्यादावन्तरङ्गवृद्धिबाधकगुणस्य निषेधेऽपि भ्रष्टावसरन्यायेन न वृद्धिभावः । सिद्धान्ते न्यायाभावादिति भावः ॥

(सिद्धान्त्येकदेशिनः समाधानभाष्यम्)

यत्तर्हि णिश्व्योः प्रतिषेधं शास्ति तेन 'नेहान्तरङ्गमस्ति' इति दर्शयति ॥

(उद्द्योतः) (भाष्ये) यत्तर्हि णिश्व्योरिति । ननु णिश्विस्थानेऽविमवी इति वदन्तं प्रति णिश्विप्रतिषेधस्य ज्ञापकत्वाभिधानमयुक्तमिति चेत् । न, ज्ञापकत्वे संभवति निमानासंभव इत्याशयात् ॥

(पूर्वोक्तज्ञापकस्थिरीकरणभाष्यम्)

यच्च करोत्यकारस्य ग्रहणं लघोरिति कृते ॥

(प्रदीपः) 'न सिचि' इति न्यायादप्येतत्सिध्यति, येन नाप्राप्तिन्यायेनान्तरङ्गस्य वृद्ध्या बाधनात् । प्रयोजनं च श्विरिजियोर्यङ्लुगन्तानां च नयत्यादीनां 'अचिरायीत्' 'अजिरायीत्' 'अनेनायीत्' 'अचेचायीत्' इत्यादौ वृद्धिसिद्धिः । अन्यथा गुणायादेशयोः कृतयोर्यान्तत्वाद्वृद्धिप्रतिषेधः स्यात् ॥

(उद्द्योतः) (भाष्ये) यच्च करोतीति । इग्ग्रहणाभावेऽकोपीदित्यादौ व्यञ्जनस्य वृद्धिवारणाय बाध्यविशेषचिन्तापक्षे त्वया सिचिवृद्ध्यपवादहलन्तलक्षणाया निषेधे तेन न्यायेन सिचिवृद्धिप्राप्तेः स्वीकारेण त्वद्रीत्या ज्ञापकमेवेति भावः ॥ एतेन सिच्यन्तरङ्गाभावेऽपि परत्वाद्गुणस्य वृद्धिबाधकताया दुर्वारत्वेनाकोपीदित्यादौ लघुत्वाभावादेव वृद्ध्यभावेऽत इति व्यर्थमेवेत्यन्त्यं ज्ञापकमसङ्गतम्, तथा णिङ्योर्गुणे वार्णपरिभाषयाऽयादेशं बाधित्वा प्राप्तवृद्धेर्निषेधाय णिश्रिग्रहणमप्यावश्यकमित्याद्यमप्यसङ्गतमित्यपास्तम् । एकदेशयुक्तित्वेनादोषात् ॥ एतदेव ध्वनयन्—'यदि तर्हि' इति सिद्धान्त्युक्तौ यथन्तर्भावसूचितं 'कृतेऽस्य चारितार्थ्येऽपि स्वप्राप्तिकाले प्राप्तस्य येन नाप्राप्तिन्यायेन बाधः' इत्येतत् आह—न्यायादपीत्यादि । बाध्यसामान्यचिन्तया च सकलान्तरङ्गबाध इति बोध्यम् । एवंच न ज्ञापकोपयोगः, नापि ज्ञापकसंभवः, नापि प्रयोजनं, वार्णपरिभाषयाऽचिरायीदित्यादौ गुणे कृतेऽयादेशात्पूर्वं वृद्धिप्राप्तेः । न वा वकारप्रश्लेषस्य फलं, नाप्यविमन्योः प्रतिषेधस्य—इति शवधातौ वृद्धिविकल्प एवेति बोध्यम् ॥

(८२ सिद्धान्तिन उपसंहारवार्तिकम् ॥ ३ ॥)

॥ * ॥ तस्मादिग्लक्षणा वृद्धिः ॥ * ॥

(भाष्यम्)

तस्मादिग्लक्षणा वृद्धिरास्थेया ॥

(उद्द्योतः) एवंच न्यनुवीदित्यादौ उवङं बाधित्वा प्राप्ताया वृद्धेर्निषेधायेग्लक्षणा सिचिवृद्धिरास्थेयेत्युपसंहरति सिद्धान्ती—तस्मादिति—भाष्ये । इग्लक्षणत्वेन निषेधायाकोपीदित्यादावनिको गुणव्यावृत्तये च । बाध्यसामान्यचिन्ता प्राप्तावसरन्यायश्चैकदेशयुक्तिर्न तु सिद्धान्तः ॥ अत एव न्यस्तारीदित्युपक्रम्य हलन्तलक्षणायाश्च नेटीति प्रतिषेध इत्युक्तमित्यलम् ॥

(इति पदोपस्थितिस्थापनम् ॥)

(अथ स्वतन्त्रविधित्वनिराकरणाधिकरणम्)

(८३ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ षष्ठ्याः स्थानेयोगत्वादिग्निवृत्तिः ॥ * ॥

(भाष्यम्)

षष्ठ्याः स्थानेयोगत्वात्सर्वेषामिकां निवृत्तिः प्राप्नोति । दधि, मधु ॥

(प्रदीपः) षष्ठ्या इति । स्वतन्त्रमिदं गुणवृद्ध्योर्विधायकमिति पूर्वः पक्षः ॥

(उद्द्योतः) विधायकमिति । इको यणचीत्यादि तु स्वविषयेऽस्य बाधकमिति न तद्वैयर्थ्यरूपो दोषः ॥ भाष्ये—इग्निवृत्तिरित्यस्य गुणवृद्धिरूपादेशेनेत्यादिः ॥

(अस्य स्वतन्त्रत्वे दूषणभाष्यम्)

पुनर्वचनमिदानीं किमर्थं स्यात् ?

(उद्द्योतः) पुनर्वचनं—'मिदेर्गुणः' इत्यादिरूपम् ॥

(८४ स्वतन्त्रत्वे दूषणसमाधानवार्तिकम् ॥ २ ॥)

॥ * ॥ अन्यतरार्थं पुनर्वचनम् ॥ * ॥

(भाष्यम्)

अन्यतरार्थमेतत्स्यात्-सार्वधातुकार्धधातुकयोर्गुण एवेति ॥

(प्रदीपः) अन्यतरार्थमिति । ननु अनिकोऽपि यथा स्यात्-इति विध्यर्थं स्यात्, न तु नियमार्थम्, नियमाद्विधेर्बलीयस्त्वात् ॥ एवं मन्यते—द्वितीयं गुणवृद्धिग्रहणमनुवर्तते, तेन गुणवृद्धिप्रदेशेष्वपि 'इकः' इत्यस्योपस्थानान्नास्त्यनिकः प्रसङ्गः ॥

(उद्द्योतः) नियमाद्विधेरिति । प्राप्तबाधादिरूपदोषापत्त्या परिसंख्यारूपो नियमो गुरुरिति भावः ॥ द्वितीयमिति । केवलविधायकत्वेऽनुवृत्त्यैव सिद्धे इत्यत्रगुणवृद्धिग्रहणमनर्थकं स्यादिति भावः ॥ यातीत्यादिनिर्देशैर्गुरोरपि नियमस्याश्रयणमित्यन्ये ॥

(८५ समानन्यायेनेतरत्राक्षेपवार्तिकम् ॥ ३ ॥)

॥ * ॥ प्रसारणे च ॥ * ॥

(भाष्यम्)

प्रसारणे च सर्वेषां यणां निवृत्तिः प्राप्नोति । अस्यापि प्राप्नोति—याता, वाता ॥

(प्रदीपः) प्रसारणे चेति । तुल्यन्यायत्वादुपन्यासः । 'इग्यणः' इत्यत्र यण इति स्थानषष्ठी । तेन यणः स्थान इग्भवति, स च संप्रसारणसंज्ञ इति वाक्यार्थः स्यात् । वाक्यभेदेन च कार्यद्वयं विधीयते ॥

(उद्द्योतः) तुल्यन्यायेति । षष्ठीदर्शनरूपो न्यायः ॥ वाक्यभेदेनेति । ष्यङः संप्रसारणमित्यादिनिर्वाहाय सामान्येन संज्ञाविधानार्थं वाक्यभेद आवश्यक इति भावः ॥

(स्वातन्त्र्ये दूषणभाष्यम्)

पुनर्वचनमिदानीं किमर्थं स्यात् ? ॥

(८६ स्वातन्त्र्ये दूषणनिराकरणवार्तिकम् ॥ ४ ॥)

॥ * ॥ विषयार्थं पुनर्वचनम् ॥ * ॥

(भाष्यम्)

विषयार्थमेतत्स्यात्-वचिस्वपियजादीनां कित्येवेति ॥

(उद्द्योतः) विषयार्थमित्यस्य निमित्तनियमार्थमित्यर्थः ॥

(८७ समानन्यायेनाक्षेपवार्तिकम् ॥ ५ ॥)

॥ * ॥ उरण्रपरे च ॥ * ॥

(भाष्यम्)

उरण्रपरे च सर्वेषामृकाराणां निवृत्तिः प्राप्नोति । अस्यापि प्राप्नोति—कर्तृ, हर्तृ ॥

(प्रदीपः) कर्तृ हर्तृ इति । अन्तरतमस्याभावात्सर्वे पर्यायेणाणः प्राप्नुवन्ति ॥

(८८ सर्वाक्षेपनिराकरणसिद्धान्तवार्तिकम् ॥ ६ ॥)

॥ * ॥ सिद्धं तु षष्ठ्यधिकारे वचनात् ॥ * ॥

(भाष्यम्)

सिद्धमेतत् ।

कथम् ?

षष्ठ्यधिकारे इमे योगाः कर्तव्याः । एकस्तावत् क्रियते तत्रैव । इमावपि योगौ षष्ठ्यधिकारमनुवर्तिष्येते ॥

(प्रदीपः) सिद्धमिति । स्वातन्त्र्यमेषां निवर्तयति । तेन यत्र षष्ठी तत्रैषामुपस्थानम्—अङ्गस्य-वच्यादीनां ऋत इद्धातोः-इत्यादौ ॥ इमावपीति । स्वरितत्वात् अनयोरन्तराऽवर्तिभिश्चायोग्यत्वात्संबन्धाभावः ॥

(उद्योतः) गुणादिविधावपि अधिकारलब्धा षष्ठीत्याह—अङ्गस्येति । तत्रोरण् रपर इत्यत्र षष्ठीत्यनुवर्त्य पूर्वोक्तार्थः सुलभः । एतयोरपि तत्रानुवृत्त्या षष्ठीति संबन्धेन तदर्थलाभः ॥ तत्रानुवर्तनं यदि लौकिकोऽधिकारस्तर्हि स आकाङ्क्षानिबन्धनः । न च षष्ठीस्थान इत्यस्याकाङ्क्षेत्यत आह—स्वरितत्वादिति ॥ लक्ष्यानुरोधाच्चेत्यपि बोध्यम् ॥

(लौकिकाधिकारसंपादकं भाष्यम्)

अथवा—षष्ठ्यधिकारे इमौ योगावपेक्षिष्यामहे॥

(प्रदीपः) अथवेति । 'षष्ठीस्थाने योगा' इत्यत्र योगविभागः करिष्यते—"षष्ठी" इति, यदेतदनुक्रान्तं तत् यत्र षष्ठी तत्रोपतिष्ठत इत्यर्थः । तत्र योग्यत्वादनयोरेवापेक्षा नान्येषाम् । ततः-"स्थानेयोगा" इति,'षष्ठी' इत्येतदुपतिष्ठते॥

(उद्योतः) षष्ठीति । योगविभागे च षष्ठीति सूत्रं साकाङ्क्षमिति लौकिकोऽपेक्षालक्षणोऽधिकार इति भावः ॥ योग्यत्वादिति । व्याख्यानाच्चेत्यपि बोध्यम् ॥ उपतिष्ठत इति । अनुवर्तत इत्यर्थः ॥

(समाधानान्तरभाष्यम्)

अथवा-इदं तावदयं प्रष्टव्यः—सार्वधातुकार्धधातुकयोर्गुणो भवति-इति, इह कस्मान्न भवति—याता, वाता ?

इदं तत्रापेक्षिष्यते-"इको गुणवृद्धी" इति ॥

यथैव तर्हि इदं तत्रापेक्ष्यते, एवमिहापि तदपेक्षिष्यामहे "सार्वधातुकार्धधातुकयोः-इको गुणवृद्धी" इति ॥ ३ ॥

इति श्रीमद्भगवत्पतञ्जलिविरचिते व्याकरणमहाभाष्ये प्रथमस्याध्यायस्य प्रथमे पादे तृतीयमाह्निकम् ॥

(प्रदीपः) अथवेति । 'अन्यतरार्थं पुनः-' इति वदताऽवश्यमेवं संबन्धः कर्तव्यः—'यत्र गुणवृद्धिशब्दोच्चारणेन गुणवृद्धी विधीयेते तत्रेक इति उपतिष्ठते' इति । अन्यथा याता वातेत्यादिविध्यर्थत्वे संभवति कथमन्यतरार्थं पुनर्वचनं स्यादित्युच्यते । अवश्यकर्तव्यायां चापेक्षायामेकवाक्यतयैवापेक्षाऽस्तु । तेनैकरूप एवास्यार्थः, न तु वाक्यभेदेन स्वातन्त्र्यं पारतन्त्र्यं च ॥ तदपेक्षिष्यामह इति । अस्य स्वातन्त्र्यं निरसितुमित्यर्थः ॥३॥

इत्युपाध्यायजैयटपुत्रकैयटकृते महाभाष्यप्रदीपे प्रथमस्याध्यायस्य प्रथमे पादे तृतीयमाह्निकम् ॥

(उद्योतः) अन्यतरार्थमिति । केवलविधित्वे पुनर्गुणवृद्धिग्रहणवैयर्थ्यमुक्तमेव ॥ न तु वाक्यभेदेनेति । एकवाक्यत्वे संभवति तस्यायुक्तत्वमिति भावः । एतेनेग्यण इत्यपि व्याख्यातम् । तत्रापि संज्ञाविधाने इगनुवादः । अनुवादत्वं च ष्यङः संप्रसारणमित्यादीनां सार्थक्यायावश्यकम् । एवञ्च-ऐकरूप्यायानुवादत्वमेवास्तु, न तु विधेयत्वं वचिस्वपीत्यादीनां नियामकत्वापादकमिति बोध्यम् ॥ तदपेक्षिष्यामह इति । एवं च यथा विधेः स्वान्याकाङ्क्षा तथाऽस्यापि स्वसंबन्धिविधेयबोधकशास्त्रापेक्षेति एकवाक्यतैवेति भावः । एवं च स्वातन्त्र्यं दूरापास्तमेव । तदाह—अस्येति । आवृत्तौ तु न मानमिति शिवम् ॥ ३ ॥

इति श्रीशिवभट्टसुतसतीगर्भजनागोजीभट्टकृते भाष्यप्रदीपोद्योते प्रथमाध्यायस्य प्रथमे पादे तृतीयमाह्निकम् ॥

अथ प्रथमाध्यायस्य प्रथमपादे चतुर्थमाह्निकम् ।

(३ परिभाषासूत्रम् १ । १ । ४ । आ. ४ ॥)

न धातुलोप आर्धधातुके ॥ १।१।४ ॥

(प्रदीपः) न धातुलोप आर्धधातुके ॥ ४ ॥ गुणवृद्ध्योः प्राधान्यादयं निषेधः, न तु तद्गुणभावादिकपरिभाषायाः । 'दीधीवेवीटाम्' इति चासंबद्धं परिभाषानिषेधे स्यात् ॥ कृत्स्नस्य धातोर्लोपे गुणवृद्धिप्रसङ्गाभावादनर्थको निषेधः स्यादिति सामर्थ्याद्धात्वेकदेशलोपोऽत्र धातुलोपोऽभिमतः, अवयवक्रिययाऽपि समुदायस्य व्यपदेशदर्शनात् । यथा-पटो दग्ध इति । अथवा समुदायशब्दोऽवयवे तद्गुणारोपाद्वर्तते ॥

(उद्योतः) न धातु ॥ ४ ॥ प्राधान्यादिति । प्राधान्यं च संस्कार्यत्वरूपम् ॥ असंबद्धमिति । अलोऽन्त्यस्येत्यनेनापि इक एव प्रसक्त्या परिभाषानिषेधे वैयर्थ्यम् ॥ कृत्स्नस्येति । दुरीणो लोपश्चेति रकसंनियोगेन कृत्स्नधातुलोपोऽस्तीति तदसंभवो नोक्तः ॥ अथवेति । आद्यपक्षे-अवयवधर्मस्य समुदाये आरोपः, अन्त्ये-समुदायधर्मस्य प्रवृत्तिनिमित्तस्य अवयवे आरोपितत्वमिति भेदः ॥

(पदकृत्याधिकरणम्)

(आक्षेपभाष्यम्)

धातुग्रहणं किमर्थम् ?

(प्रदीपः) धातुग्रहणमिति । उपसर्जनस्यापि यथा परामर्शस्तथा 'केषां शब्दानां' इत्यत्र प्रतिपादितम् ॥ विनापि धातुग्रहणेन लोपविशेषणमार्धधातुकं विज्ञास्यते । अनुब-

न्धलोपस्य चानैमित्तिकत्वात् 'लविता' इति गुणप्रतिषेधो न भविष्यतीति प्रश्नः ॥

(उद्द्योतः) परामर्शः–शब्देन पृथगुपादानम् ॥ प्रतिपादितमिति । युक्त्या पृथक् निष्कर्षादिति भावः ॥ लोपविशेषणमिति । सूत्रे श्रुतत्वादिति भावः ॥

(समाधानभाष्यम्)

इह मा भूत्—लूञ् लविता-लवितुम्, पविता-पवितुम् ॥

(प्रदीपः) सिद्धान्ते तु गुणवृद्धिविशेषणमार्धधातुकग्रहणमित्यभिप्रायः ॥ अनुबन्धो न धात्वेकदेशः, यस्मादुपदेश एवेत्संज्ञा । प्रयोगे तु लूशब्द एव धातुसंज्ञः, केवलमसौ ञित्कार्यं लभते । लूशब्दस्यैव हि क्रियावाचित्वमिति तस्यैव युक्ता धातुसंज्ञा ॥

(उद्द्योतः) सिद्धान्ते त्विति । निषेध्यत्वेन गुणवृद्ध्योः शाब्दप्राधान्यात् लोपस्य तद्विशेषणत्वादिति भावः ॥ न च लोपशब्दोऽधिकरणघञन्तः, अदर्शनं लोप इत्यादौ भावसाधनस्यैव प्रसिद्धत्वात् ॥ गणे सानुबन्धस्य पाठात् विशिष्टस्यैव धातुत्वं स्यादत आह—अनुबन्धइति ॥ यस्मादिति । उपदेशपदाभावेऽपि अन्तरङ्गत्वात्सर्वतः पूर्वं सा । धातुसंज्ञा तु प्रत्ययविशेषे विधित्सिते-इति भावः ॥ धातुसंज्ञेत्संज्ञयोः समकालत्वेऽपि न क्षतिरित्याह—लूशब्दस्यैवेति । अन्वयव्यतिरेकाभ्यां तस्यैव क्रियावाचित्वावगमात् । गणपठितक्रियावाचिनां च धातुत्वविधानादिति भावः ॥

(आक्षेपभाष्यम्)

आर्धधातुक इति किमर्थम् ?

(समाधानभाष्यम्)

'त्रिधा॑ ब॒द्धो वृ॑ष॒भो रो॑रवीति' (ऋ. सं. ४।५८।३) ॥

(प्रदीपः) रोरवीतीति । सत्यार्धधातुकग्रहणे शब्दवत्त्वादन्यपदार्थे बहुव्रीहिरसंदिग्धो भवति, नान्यथा ॥ क्रमेण सूत्रप्रत्याख्यानायार्धधातुकस्य च लोपविशेषणत्वे धातुग्रहणानर्थक्यप्रतिपादनाय प्रत्युदाहरणोपन्यासः ॥

(उद्द्योतः) रोरवीति–यङ्लुगन्तस्य रूपम् ॥ शब्दवत्त्वात्–शब्देनोपादानात् ॥ नान्यथेति । अन्यथाऽन्तरङ्गत्वात्तत्पुरुष एव स्यादित्यर्थः ॥ ननु पदप्रयोजनचिन्ता वृत्तिकारस्योचिता, न भाष्यकारस्येत्यत आह—क्रमेणेति । तत्तत्पदप्रयोजनखण्डनक्रमेणेत्यर्थः ॥ क्रममेवाह—आर्धधातुकस्य चेति ॥

(आर्धधातुकपदार्थान्वयाधिकरणम्)

(पक्षद्वयोपस्थापकभाष्यम्)

किं पुनरिदमार्धधातुकग्रहणं लोपविशेषणम्—'आर्धधातुकनिमित्ते लोपे सति ये गुणवृद्धी प्राप्नुतस्ते न भवतः' इति ।

आहोस्वित् गुणवृद्धिविशेषणमार्धधातुकग्रहणम्—'धातुलोपे सत्यार्धधातुकनिमित्ते ये गुणवृद्धी प्राप्नुतस्ते न भवतः' इति ?

किं चातः ?

(प्रदीपः) किं पुनरिति । आर्धधातुकग्रहणं लोपविशेषणं वा, गुणवृद्धिविशेषणं वा, बहुव्रीहिपक्षे उभयविशेषणं वा-इति पक्षत्रयसंभवात् प्रश्नः ॥

(उद्द्योतः) लोपविशेषणम्-श्रुतत्वात् ॥ गुणादिविशेषणम्-प्राधान्यात् ॥ तत्र लोपविशेषणत्वे 'आर्धधातुके परे पूर्वस्य धात्वंशस्य लोपे' इति वाच्योऽर्थस्तत्फलितमुक्तम्—भाष्ये—आर्धधातुकनिमित्ते लोप इति ॥ एवं गुणवृद्धिविशेषणत्वे 'आर्धधातुके परे प्रत्यासत्त्या पूर्वस्य धातोर्ये गुणवृद्धी' इति वाच्योऽर्थः । अनुवादेऽपि 'इको गुणवृद्धी' 'अचश्च' इति परिभाषाऽतिरिक्तपरिभाषाणां प्रवृत्तिस्वीकारात् । तत्फलितमुक्तम्—आर्धधातुकनिमित्ते ये इति ॥ प्राप्नुत इत्यनेन प्रसक्तस्यैव निषेध इति सूचयति ॥ बहुव्रीहीति । उभयानुग्रहायेति भावः ॥ यद्यपि 'धातुलोपे' इति समस्तमार्धधातुकविशेषणं तथापि विशेषणशब्दः परिच्छेदकपर इति न दोषः ॥

(पक्षद्वये दोषदर्शकं भाष्यम्)

यदि लोपविशेषणम्, 'उपेद्धः, प्रेद्धः' अत्रापि प्राप्नोति ॥

अथ गुणवृद्धिविशेषणम्, 'क्नोपयति' अत्रापि प्राप्नोति ॥

(उभयेष्टापत्तिभाष्यम्)

य॑थेच्छसि तथाऽस्तु ॥

(प्रथमपक्षाङ्गीकारभाष्यम्)

अस्तु लोपविशेषणम् ॥

(पूर्वोक्तदोषस्मारकभाष्यम्)

कथम्—'उपेद्धः प्रेद्धः' इति ?

(प्रदीपः) प्रेद्ध इति । नन्वाद्गुणोऽनिग्लक्षण इति तन्निषेधो न भविष्यति, परिहारान्तराभिधानादेतन्नाश्रितमित्यदोषः ॥

(उद्द्योतः) नन्वाद्गुण इति । नन्विक्स्थानिकत्वादयमपि इग्लक्षणः । न चात्राप्यनुवृत्तमिक इति स्वरूपपरम्, उत्तरसूत्रे इव स्वरूपपदार्थकत्वव्यवस्थापकचशब्दाभावादिति चेत् । न, इको गुणवृद्धी इति संपूर्णमनुवर्त्य यत्रेदं तत्र न धात्वित्युपतिष्ठत इत्यर्थेनास्यापि परिभाषात्वाङ्गीकार इति भावात् ॥ यद्वा यत्रेदं तद्विहिते गुणवृद्धी नेत्यर्थः । तद्वक्ष्यति—'यत्रेक्परिभाषा व्याप्रियते तत्रायं निषेधः' इति 'इक्प्रकरणात्'इति भाष्यप्रतीके ॥ अर्थाधिकारेण स्वरूपपरस्यैवेक इत्यस्यानुवर्तनाद्वा ॥

(दोषोद्धारकं भाष्यम्)

बहिरङ्गो गुणोऽन्तरङ्गः प्रतिषेधः । 'असिद्धं बहिरङ्गमन्तरङ्गे' ॥

(प्रदीपः) बहिरङ्ग इति । यदा पूर्वं प्रत्ययः पश्चादुपसर्गयोगस्तदा प्रतिषेधोऽन्तरङ्गः, गुणो बहिरङ्गः ॥ यदा तु पूर्वमुपसर्गयोगस्तदा गुणोऽन्तरङ्गः पश्चात्प्रत्ययोत्पत्तौ निषेधो बहिरङ्गः । सर्वथा बहिरङ्गस्यासिद्धत्वादिष्टसिद्धिः । ननु **नाजानन्तर्ये** इति निषेधात् कथं परिभाषाप्रवृत्तिः ? यत्र कार्यविधावानन्तर्येणाचोराश्रयणं तत्र निषेधादनुपस्थानं परिभाषायाः । यथा—अक्षद्यूरिति । तत्र हि '**इको यणचि**' इति वचनादिगचोराश्रयणम् । अस्मिंस्तु प्रतिषेधसूत्रे नास्त्यचोराश्रयणमित्यदोषः ॥

(उद्योतः) यदेति । पूर्वं धातुः साधनेनेति सिद्धान्तपक्षे इत्यर्थः ॥ यदा त्विति । पूर्वं धातुरुपसर्गेणेति पक्षे पूर्वमेव जातस्य निषेधायोगादिति भावः ॥ बहिरङ्गस्यासिद्धत्वादिति । द्वितीये बहिरङ्गनिमित्तस्यासिद्धत्वात्–विधिप्रवृत्तिकालेऽनिष्पन्नत्वात् तन्निषेधाप्राप्तेरिष्टसिद्धिरित्यर्थः ॥ एतेन 'जातस्य बहिरङ्गस्यान्तरङ्गे कर्तव्येऽनेनासिद्धत्वप्रतिपादनेऽपि जातेऽन्तरङ्गे पश्चात्प्राप्तबहिरङ्गस्यानेनासिद्धत्वप्रतिपादने मानाभावः फलाभावो ज्ञापकविरोधश्च' इत्यपास्तम् ॥ परं स्वयं पक्षः षुद्काग्पूर्वे इत्यादिसूत्रेषु भाष्ये दूषित इति भाष्योक्तमेव सम्यक् ॥ नन्विति । इयं च परवत्तुकोरिति सूत्रेण ज्ञापिता । अन्यथा बहिरङ्गासिद्धत्वेनैव सिद्धे तद्वैयर्थ्यं स्पष्टमेव ॥ **अचोरिति** द्वित्वमविवक्षितम, धर्मिग्राहकमानस्य तथैव सत्त्वात् ॥ **अनुपस्थानमिति** । अक्षद्यूरित्यादि ॥ तत्र हीति । ततश्च यणि ऊडसिद्धो न ॥ "तेनासिद्धपरिभाषाया अनित्यत्वं ज्ञाप्यते । अत एव भाष्ये—विप्रतिषेधसूत्रभिन्नस्थले न काप्येतदुल्लेखः । यथा–असिद्धपरिभाषाज्ञापकं विप्रतिषेधसूत्रे उक्तमपि पुनर्वाह ऊठ्सूत्रे उक्तं" इति विवरणकृतः ॥ असिद्धिरिति । निषेधस्य प्राप्तिपूर्वकत्वात्पश्चात्प्रवर्तमाने इत्यर्थः ॥

(लाघवभाष्यम्)

यद्येवं, नार्थो धातुग्रहणेन ॥

(धातुग्रहणाभावे दोषस्मारकभाष्यम्)

इह कस्मान्न भवति—लूञ्-लविता, लवितुम्, लवितव्यं-इति ?

(समाधानभाष्यम्)

आर्धधातुकनिमित्ते लोपे प्रतिषेधः । न चैष आर्धधातुकनिमित्तो लोपः ॥

(द्वितीयपक्षस्वीकारभाष्यम्)

अथवा—पुनरस्तु गुणवृद्धिविशेषणम् ॥

(आक्षेपस्मारणभाष्यम्)

ननु चोक्तम्—क्नोपयतीत्यत्रापि प्राप्नोतीति ॥

(उद्योतः) क्नूयधातोर्णिचि पुकि **लोपो व्योरिति** यलोपः ॥

(समाधानभाष्यम्)

नैष दोषः,

निपातनात्सिद्धम् ॥

किं निपातनम् ?

"चेले क्नोपेः" इति ॥

(इत्यार्धधातुकपदार्थान्वयविचाराधिकरणम्)

(अथ परिगणनाधिकरणम्)

(वार्तिकावतरणभाष्यम्)

परिगणनं कर्तव्यम्—

(८९ परिगणनपूर्वपक्षिवार्तिकम् ॥ १ ॥)

॥ * ॥ यङ्यक्क्यवलोपे प्रतिषेधः ॥ * ॥

(भाष्यम्)

यङ्-यक्-क्य-वलोपे प्रतिषेधो वक्तव्यः ॥

यङ्—बेभिदिता, मरीमृजः ।

यक्—कुषुभिता, मगधकः ।

क्य—समिधिता, दृषदकः ।

वलोपे— जीरदानुः ॥

(प्रदीपः) **यङ्यक्क्यवलोप इति** । 'व' इत्यत्राकारो विवक्षितः । तेन धातुपाठे योऽकारान्तः पठितस्तस्य ग्रहणम् । अन्यथा स्रिविः कथं निवार्येत ?

बेभिदितेति । बेभिद्यशब्दात्तृच्, इट्, 'यस्य हलः' इति यलोपः ॥ **मरीमृज इति** । 'यङोऽचि च' इति यङ्लुक् ॥ कुषुभमगधशब्दौ कण्ड्वादिगणपठितौ धातू, ताभ्यां यक्, 'ण्वुल्तृचौ', 'यस्य हल' इति यलोपः ॥ समिद्दृषच्छब्दाभ्यां क्यजन्ताभ्यां प्रत्ययौ-'ण्वुलतृचौ', 'क्यस्य विभाषा' इति यलोपः ॥

(**उद्योतः**) वाक्यकारः सूत्रेऽव्याप्त्यतिव्याप्तिपरिहाराय परिगणनमाह—**परिगणनमिति**–भाष्ये ॥ अत्र **यस्य हल** इति लोपः समुदायलोप इति मत्वा यक्क्ययोः परिगणनं,'बेभिदिता' इत्युदाहरणं च बोध्यम् ॥

(भाष्यम्)

किं प्रयोजनम् ?

(९० परिगणनप्रयोजनवार्तिकम् ॥ २ ॥)

॥ * ॥ नुम्लोपे स्रिव्यनुबन्धलोपेऽप्रतिषेधार्थम् ॥ * ॥

(भाष्यम्)

नुम्लोपे स्रिवि अनुबन्धलोपे च प्रतिषेधो मा भूदिति ॥

नुम्लोपे—अभाजि, रागः, उपबर्हणम् ।

स्रिवेः—आस्रेमाणम् ।

अनुबन्धलोपे—लूञ्-लविता लवितुम् ॥

(प्रदीपः) **नुम्लोप इति** । 'नुम्' इति नकारस्य पूर्वाचार्यसंज्ञा ॥ **उपबर्हणमिति** । 'बृहि वृद्धौ' इदित्त्वान्नुम् । '**बृंहेरच्यनिटि**' इति वार्तिकेन नलोपः ॥ **आस्रेमाणमिति** । अस्रेमाणमित्यादि वेदे पठ्यते । तत्र नञ्पूर्वात् **स्रिवेर्मनिन्**-प्रत्ययः ॥ ऊडादेशश्छान्दसत्वान्न भवति ॥ परिगणने सति धातुग्रहणं न कर्तव्यं भवतीत्यनुबन्धलोपः प्रयोजनत्वेन पठितः ॥

(**उद्योतः**) ननु भञ्जिरञ्जोरौपदेशिकनस्यैव '**भञ्जेश्च चिणि**' '**रञ्जेश्च**' '**घञि च**–' इत्यादिना लोप इति नुम्लोप इत्यसङ्गतमत आह—**नुमितीति** ॥ नन्वनिदिद्वृहिर्, बृहिणा इदं सिद्धमत आह—

वृहि वृद्धाविति ॥ न नास्त्येवेति पूर्वपक्ष्याशयः ॥ ऊडादेश इति । ज्वरत्वरस्रिवीत्यनेन ॥

(आक्षेपभाष्यम्)

यदि परिगणनं क्रियते, 'स्यदः, प्रश्रथः, हिमश्रथः' इत्यत्रापि न प्राप्नोति ॥

(उद्द्योतः) भाष्ये—इत्यत्रापि प्राप्नोतीति । वृद्धिरिति शेषः॥ 'न प्राप्नोति' इति पाठे-निषेध इति शेषः ॥

(समाधानभाष्यम्)

वक्ष्यत्येतत्—*निपातनात्स्यदादिषु* इति ॥

(उद्द्योतः) निपातनादिति । 'स्यदो जवे' 'अवोदैधौद्मप्रश्रथहिमश्रथाः' इति निपातनस्य नलोपमात्रफलकत्वे नलोपविधानेनैव सिद्धे निपातनवैयर्थ्यापत्तिरिति भावः ॥

(आक्षेपभाष्यम्)

तर्त्तार्हि परिगणनं कर्तव्यम् ॥

(परिगणनप्रत्याख्यानभाष्यम्)

न कर्तव्यम् ॥

(आक्षेपभाष्यम्)

नुम्लोपे कस्मान्न भवति ?

(सिद्धान्तसमाधानभाष्यवार्तिकम्)

इक्प्रकरणान्नुम्लोपे वृद्धिः ।

(भाष्यम्)

इग्लक्षणयोर्गुणवृद्ध्योः प्रतिषेधः । न चैषेग्लक्षणा वृद्धिः ॥

(प्रदीपः) इक्प्रकरणादिति । तेन यत्रेक्परिभाषा स्थान्यन्तरनिवृत्तये व्याप्रियते तत्रायं निषेध इत्यर्थः ॥

(उद्द्योतः) तेनेति । अन्यथा 'ओर्गुणः' इत्यादावपि परिभाषाप्रवृत्तौ तस्यापीग्लक्षणत्वे लैगवायन इत्यादौ निषेधः स्यादिति भावः ॥ यत्रेक्परिभाषेति । न चेक इत्यनुवर्त्य 'इको न ते' इत्येव व्याख्यानमुचितमिति वाच्यम् । मरीमृजः सरीसृप इत्यादाविकः प्रत्ययाव्यवहितपूर्वत्वाभावान्निषेधानापत्तेः । तदाह भाष्ये—इग्लक्षणयोरिति । यथैतदर्थलाभस्तथोक्तम् । इक्परिभाषालक्षणयोरिति तदर्थः ॥

(आक्षेपभाष्यम्)

यदीग्लक्षणयोर्गुणवृद्ध्योः प्रतिषेधः, 'स्यदः, प्रश्रथः, हिमश्रथः' इत्यत्र न प्राप्नोति ॥

इह च प्राप्नोति-'अवोदः, एधः, ओद्मः' इति ॥

(९१ सिद्धान्तसमाधानवार्तिकम् ॥ ३ ॥)

॥ * ॥ निपातनात्स्यदादिषु ॥ * ॥

(भाष्यम्)

निपातनात्स्यदादिषु प्रतिषेधो भविष्यति, न भविष्यति च ॥

(आक्षेपभाष्यम्)

यदीग्लक्षणयोर्गुणवृद्ध्योः प्रतिषेधः, स्रिव्यनुबन्धलोपे कथम् । स्रिवेः-आस्रेमाणम्, लून्लविता ॥

(सिद्धान्तसमाधानभाष्यवार्तिकम्)

प्रत्ययाश्रयत्वादन्यत्र सिद्धम् ।

(भाष्यम्)

आर्धधातुकनिमित्ते लोपे प्रतिषेधः । न चैष आर्धधातुकनिमित्तो लोपः ॥

(प्रदीपः) प्रत्ययाश्रयत्वादिति । लोपविशेषणमार्धधातुकग्रहणमित्यर्थः ॥

(उद्द्योतः) लोपेति । प्रत्ययाश्रयत्वादिति भाष्यस्य—लोपे आर्धधातुकप्रत्ययनिमित्तकत्वाश्रयणादित्यर्थ इति भावः ॥

(आक्षेपभाष्यम्)

यद्यार्धधातुकनिमित्ते लोपे प्रतिषेधः, 'जीरदानुः' (ऋ० सं० ५।८३।१) अत्र न प्राप्नोति ॥

(प्रदीपः) जीरदानुरिति । वर्णनिमित्तोऽत्र वलोपो न प्रत्ययनिमित्तः ॥

(उद्द्योतः) न प्रत्ययेति । प्रत्ययस्याश्रुतत्वादनाक्षिप्तत्वादिति भावः ॥

(९२ सिद्धान्तसमाधानवार्तिकम् ॥ ४ ॥)

॥ * ॥ रकि ज्यः संप्रसारणम् ॥ * ॥

(भाष्यम्)

नैतज्जीवे रूपम्, रक्येतत् ज्यः संप्रसारणम् ॥

(प्रदीपः) रकि ज्य इति । एवं च 'जीर' इत्यवग्रहः सिध्यति । बहुव्रीहित्वाच्च जीरदानुशब्दे रेफाकार उदात्तः ॥

(उद्द्योतः) अवश्यं जीरदानुशब्दस्यैवमेव व्युत्पत्तिः कार्येत्याह—एवं चेति । अवान्तरपदत्वे सत्येवावग्रह इत्युत्सर्गादिति भावः ॥ ननु रदानुप्रत्यये रेफाकार उदात्तः, समासे स्यन्तोदात्तः स्यादत आह—बहुव्रीहिति । जीरस्य प्रत्ययस्वरेणान्तोदात्तस्य बहुव्रीहौ पूर्वपदप्रकृतिस्वरेणेत्यर्थः ॥ जीवेर्विधि तु गुणनिषेधो भवत्येव ॥ एतेनार्धधातुकत्वेन यत्र लोपे निमित्तता तत्रैव लोपे निषेध इत्यपास्तम्, वार्तिकविरोधात् । यक्लोऽच्चि चेत्यत्रापि तस्यैवानिमित्तत्वाल्लोलुव इत्याद्यसिद्ध्यापत्तेश्च ॥ धिन्व्यादिभ्यस्तु विजभाव एव ॥

(एकदेशिभाष्यम्)

यावता चेदानीं रकि जीत्ररपि सिद्धं भवति । कथमुपबर्हणम् ?

(उद्द्योतः) भाष्ये—यावता चेदानीमिति । किंत्वेन गुणनिषेधादिति भावः ॥ अत्र वलोपो लोपो व्योरित्यनेन । इदं च यथाश्रुतसूत्रमते । वलोपप्रत्याख्याने तु रकि ज्य इत्येव शरणम् ॥

(सिद्धान्तिभाष्यम्)

वृहिः प्रकृत्यन्तरम् ॥

(प्रदीपः) वृहिरिति । 'वृह वृहि वृद्धौ' इति पाठात् ॥

(आक्षेपभाष्यम्)

कथं ज्ञायते—वृहिः प्रकृत्यन्तरमिति ?

(सिद्धान्तिभाष्यम्)

अचि इति हि लोप उच्यते, अनजादावपि दृश्यते-

निवृह्यते ।

अनिटि-इति चोच्यते, इडादावपि दृश्यते-निबर्हिता, निबर्हितुमिति ।

अजादावपि न दृश्यते-बृंहयति, बृंहकः ॥

(उपसंहारभाष्यम्)

तस्मान्नार्थः परिगणनेन ॥

(आक्षेपभाष्यम्)

यदि परिगणनं न क्रियते 'भेद्यते, छेद्यते' अत्रापि प्राप्नोति ॥

(प्रदीपः) भेद्यत इति । गुणो णिलोपश्चार्धधातुकनिमित्त इति पक्षद्वयेऽपि दोषः । अपवादविषयपरिहाराच्चान्तरङ्गोऽपि गुणोऽत्र न प्रवर्तत इत्युपन्यासः ॥

(उद्द्योतः) पक्षद्वयेऽपीति । तेनैणोभयविशेषणत्वपक्षेऽपि–इत्यपि बोध्यम् ॥ गुणो ण्याश्रयः । णिलोपो यगाश्रयः ॥ अपवादेति । प्रकल्प्य वाऽपवादविषयमिति परिभाषयेति भावः ॥ एतेन "गुणप्रतिषेधौ यत्र समानकालौ तत्र चरितार्थो निषेधो नान्तरङ्गं गुणं बाधितुं क्षमते" इत्यपास्तम् ॥ न च 'भेद्यते' इत्यत्राचः परस्मिन्निति णिलोपस्य स्थानिवत्त्वेन तत्राभावातिदेशस्य च सत्त्वेन स्थानिनि णिचि सति अभवतो निषेधस्य लोपेऽप्यभावातिदेशान्न दोष इति वाच्यम् । स्थानिवद्भावाश्रयणे सूत्रं प्रत्याख्यातमेव-इति तदनाश्रयणेन सूत्रवद् तदनाश्रयणेनैवायं दोष इत्याशयात् ॥

(समाधानभाष्यम्)

नैष दोषः । धातुलोप इति नैवं विज्ञायते— 'धातोर्लोपः-धातुलोपः, धातुलोपे' इति ।

कथं तर्हि ?

'धातोर्लोपो यस्मिंस्तदिदं, धातुलोपे' इति ॥

(प्रदीपः) कथं तर्हीति । बहुव्रीहौ सत्येकार्धधातुकनिमित्तत्वं लोपस्य गुणवृद्ध्योश्चाश्रितमिति 'भेद्यते' इत्यादौ भिन्ननिमित्तत्वाद्गुणो न निषिध्यते ॥

(उपसंहारभाष्यम्)

तस्मादिग्लक्षणा वृद्धिः ॥

(उद्द्योतः) भाष्ये—तस्मादिग्लक्षणा वृद्धिरिति । प्रतिषेध्येति शेषः । अत एवाभाजीत्यादिसिद्धिरिति भावः ॥

(इति परिगणनाधिकरणम्)

(अथेग्लक्षणत्वे दोषनिराकरणाधिकरणम्)

(आक्षेपभाष्यम्)

यदि तर्हीग्लक्षणयोर्गुणवृद्ध्योः प्रतिषेधः, 'पापचकः, पापठकः, मगधकः, दृषदकः' अत्र न प्राप्नोति ॥

(९३ सिद्धान्तिसमाधानवार्तिकम् ॥ १ ॥)

॥ * ॥ अल्लोपस्य स्थानिवत्त्वात् ॥ * ॥

(भाष्यम्)

अकारलोपे कृते तस्य स्थानिवत्त्वात् गुणवृद्धी न भविष्यतः ॥

(उद्द्योतः) अकारलोप इति । अतो लोप इत्यनेन । यङ्लुगन्ताण्ण्वुलि तु सूत्रमतेऽपि निषेधो न, आर्धधातुकनिमित्तलोपाभावात् ॥

(इतीग्लक्षणत्वे दोषनिराकरणम्)

(अथ सूत्रप्रत्याख्यानाधिकरणम्)

(९४ सिद्धान्तवार्तिकम् ॥ १ ॥)

॥ * ॥ अनारम्भो वा ॥ * ॥

(भाष्यम्)

अनारम्भो वा पुनरस्य योगस्य न्याय्यः ॥

(आक्षेपभाष्यम्)

कथं—'बेभिदिता-मरीमृजकः-कुषुभिता-समिधिता' इति ?

(समाधानभाष्यम्)

अत्राप्यकारलोपे कृते तस्य स्थानिवद्भावात् गुणवृद्धी न भविष्यतः ॥

(उद्द्योतः) मरीमृजक इति । अत्राल्लोपस्य स्थानिवत्त्वे क्ङित्यजादौ वेष्यत इति विकल्पो न, व्यवस्थितविभाषाऽऽश्रयणात् ॥

(आक्षेपभाष्यम्)

यत्र तर्हि स्थानिवद्भावो नास्ति तदर्थमयं योगो वक्तव्यः ॥

क्व च स्थानिवद्भावो नास्ति ?

यत्र हलचोरादेशः–लोलुवः-पोपुवः-मरीमृजः सरीसृप इति ॥

(प्रदीपः) यत्र हलचोरादेश इति । लुका कृत्स्नो यङ् लुप्यत इत्याशयः ॥

(समाधानभाष्यम्)

अत्राप्यकारलोपे कृते तस्य स्थानिवद्भावात् गुणवृद्धी न भविष्यतः ॥

(प्रदीपः) अत्रापीति । कृतेऽप्यकारलोपे एकदेशविकृतमनन्यवदिति यकारः प्रत्ययसंज्ञो भवत्येवेति भावः ॥

(उद्द्योतः) नन्वेवं लुक्शास्त्रं व्यर्थं स्यादत आह—कृतेऽपीति । अवशिष्टे तच्चरितार्थमिति भावः ॥

(समाधानबाधकभाष्यम्)

लुकि कृते न प्राप्नोति ॥

(उद्द्योतः) भाष्ये—लुकि कृते इति । अनवकाशत्वादन्तरङ्गानपीति न्यायाच्च लुकि कृते लोपो न प्राप्नोतीत्यर्थः ।

(समाधानसाधकभाष्यम्)

इदमिह संप्रधार्यम्—लुक् क्रियतामल्लोप इति, किमत्र कर्तव्यम् ?

परत्वादल्लोपः ॥

(उद्द्योतः) इतर आशयानभिज्ञ आह—परत्वादिति ॥

(समाधानबाधकभाष्यम्)

नित्यो लुक् । कृतेऽप्यल्लोपे प्राप्नोति, अकृतेऽपि

प्राप्नोति ॥

(प्रदीपः) नित्यो लुगिति । लुक्शास्त्रप्रवृत्तिर्नित्या ॥

(उद्योतः) ननु यस्य लोपः कृतस्तस्य लुगप्राप्तेराह—लुक्शास्त्रेति ॥

(समाधानसाधकभाष्यम्)

लुगप्यनित्यः ।

कथम् ?

अन्यस्य कृते लोपे प्राप्नोति, अन्यस्याकृते । "शब्दान्तरस्य च प्राप्नुवन्विधिरनित्यो भवति" ॥

(समाधानबाधकभाष्यम्)

अनवकाशस्तर्हि लुक् ॥

(प्रदीपः) अनवकाश इति । नाप्राप्ते लोपे लुगारम्भात् ॥

(समाधानसाधकभाष्यम्)

सावकाशो लुक् ।

कोऽवकाशः ?

अवशिष्टः ॥

(प्रदीपः) सावकाश इति । भिन्नविषयौ लुग्लोपौ । आकारस्य लोपः, यकारस्य लुक् । ततश्च नास्ति येन नाप्राप्तिन्यायः ॥

(अभ्युपेत्य समाधानभाष्यम्)

अथापि कथंचिदनवकाशो लुक् स्यात्, एवमपि न दोषः । अल्लोपे योगविभागः करिष्यते—"अतो लोपः" । ततः "यस्य", यस्य च लोपो भवति । अत इत्येव ॥

किमर्थमिदम् ?

लुकं वक्ष्यति तद्बाधनार्थम् ।

ततः—"हलः", हल उत्तरस्य च यस्य लोपो भवतीति ॥

(प्रदीपः) अथापीति । 'यङोऽचि च' इत्यत्र यकाराकारसमुदायस्य 'यङः' इति निर्दिष्टस्य विवक्षितत्वादवयवे च यङ्व्यपदेशस्य गौणत्वादिति भावः ॥

(उद्योतः) गौणत्वादिति । अतिदेशविषये गौणत्वाङ्गीकारेऽतिदेशवैयर्थ्यापत्तेरिदं चिन्त्यम् ॥ किंच भिन्नविषयेऽपि बाध्यबाधकभावो दृष्टः, यथा—ष्यङो लिटीति संप्रसारणस्य यकारे चारितार्थ्येऽपि हलादिः शेषबाधकता । भाष्यकारोऽपि मिदचोऽन्त्यादित्यस्य विषयभेदेऽपि प्रत्ययपरत्वबाधकतां वक्ष्यति ॥ तस्मात्कृते चारितार्थ्येऽपि तत्प्राप्तिकालेऽवश्यं प्राप्त्याऽपवादत्वं भवत्येवेत्याशयः ॥ असंभव एव बाधकत्वमिति वार्तिकानुयायिना सावकाशो लुगित्युक्ते स एव 'अथापि' इत्याह—इति तदुक्तिः—कथंचिदिति ॥ भाष्ये—अत इत्येवेति । अलोऽन्त्यपरिभाषया, अत इत्यनुवृत्तेर्वेति भावः ॥ अयं च लुकोऽपवादः । एवं चावशिष्टस्य लुगिति बोध्यम् । अत्र च अस्जो रोपधेति सूत्रादन्यतरस्यांग्रहणस्य मण्डूकप्लुत्याऽनुवर्तनेन योगविभागस्येष्टसिद्ध्यर्थत्वेन च क्वचिदेव पृथग्लोपः, न सर्वत्रेति बोध्यम् ॥ मरीमृज इत्यत्र विकल्पस्तु न, व्यवस्थितविभाषाऽऽश्रयणात् । यद्वा तत्र विकल्प इष्ट एव । तदर्थं सूत्रकृतोऽप्येतत्कल्पनावश्यकत्वं मनसि निधायैव तामाश्रित्य सूत्रप्रत्याख्यानमेव वरमिति भाष्याशयः ॥ लोलुयादौ ढवढि अनादिष्टादचः पूर्वस्य विधेरभावेन स्थानिवत्त्वाभावेऽपि नोपधागुणः, अन्तःपूर्वत्वेन दृष्टलोल्शब्दात्परस्य गुणे कर्तव्ये पञ्चमीसमासेनाल्लोपस्य स्थानिवद्भावसौलभ्यात् । निमित्तत्वेनाश्रितात्पूर्वत्वादित्यर्थे तु न मानम् । अतिप्रसङ्गस्य तदनित्यत्वेनैव परिहारात् । भाष्यानुक्त्या तदनित्यत्वाभावेऽपि पूर्वशास्त्रपरस्याव्यवहितस्यैव ग्रहणेन 'हे गौः' इत्यत्रादोषः । अचः पूर्वत्वांशे स्वरग्रहणाद्भाष्यप्रामाण्याच्चाव्यवधानांशबाधेऽप्यत्र तद्बाधे मानाभावात् । अतिदेशप्रवृत्तिप्राक्कालिकं च तदंशेऽव्यवधानं निविष्टम् । किं चाशास्त्रीयस्यापि तस्य तत्स्थानापन्ने तद्धर्मलाभ इति लोकन्यायेनातिदेशलाभ इति स्थानिवत्सूत्रे वक्ष्यते । लोल् इत्यस्य लोलुवादेशत्वात् च गुणघटितो लोलोवित्यादेश इत्याहुः ॥ दरीदृश इत्यत्राङ्निमित्तगुणस्तु न, अस्याङ्स्त्वैकगोचरत्वेन लाक्षणिकतया अङ्ग्रहणेनाग्रहणात् ॥ अत एव दरीदृशक इत्यादौ यङन्तात्ण्वुलि अङ्निमित्तगुणाभावः । जङ्गमक इत्यादौ यङन्तात्ण्वुलि उपधालोपश्च, 'अनङि' इति निषेधाप्रवृत्तेः ॥ जङ्गम इत्यादौ तूक्तयुक्त्या समुदायस्य लुगेवेति न दोषः ॥ निजेगिल इत्यादौ ग्रो यङीति नित्यत्वा[illegible]मेव । सूत्रमतेऽपि न लुमतेति निषेधस्यानित्यत्वात् यङ्परत्वमस्ति । न वेति विभाषेति सूत्रे भाष्ये चेदं ध्वनितमिति तत्रैव निरूपयिष्यामः ॥ यदि जरीगृह्यादेः साधुत्वं तदर्थं तेषाञ्च संप्रसारणयङ्क्वितिगुणाविष्टौ, तर्हि सूत्रमतेऽपि न लुमतेति निषेधानित्यत्वेन साधनीयौ । भाष्यप्रामाण्यादिष्टाविति गम्यते । अत एव पृथग्लोपे यङो विषयापहाराभावेन अजेर्वी आदेशे यणि वेव्य इति स्यादित्यपास्तम्, योगविभागस्य काचित्कत्वेन तत्र लुक एव प्रवृत्त्याऽक्षतेः ॥ पुर्वादिभ्यो यान्तेभ्यो क्विप् नास्त्येव, अनभिधानात् । इदं च लोपो व्योरिति सूत्रे भाष्येऽपि ध्वनितम् । एतद्भाष्यविरुद्धप्रयोगाणां भाष्यानुक्तानामनभिधानमित्यन्ये ॥ न चैवं 'न धातुलोप आर्धधातुके' इत्येव सिद्धे आर्धधातुकग्रहणं व्यर्थमिति वाच्यम् । लोपार्धधातुक इत्येव षष्ठीतत्पुरुषेण लोपनिमित्तार्धधातुक इत्यर्थेन लूञादेर्व्यावृत्तिसिद्धौ धातुग्रहणवत्तस्यापि सत्त्वात् ॥ भाष्ये—लुकं वक्ष्यतीति । लुक् अतोलोपापवादः । अपवादश्च प्रायेण पश्चात्पठ्यत इति भविष्यन्निर्देशः ॥

(आक्षेपभाष्यम्)

इहापि तर्हि परत्वाद्योगविभागाद्वा लोपो लुकं बाधेत—"कृष्णो नोनाव वृषभो यदीदम् (ऋ. सं. १।७९।२)" नोनूयतेर्नोनाव ॥

(समाधानभाष्यम्)

समानाश्रयो लुक् लोपेन बाध्यते ।

कश्च समानाश्रयः ?

यः प्रत्ययाश्रयः । अत्र च प्रागेव प्रत्ययोत्पत्तेर्लुग्भवति ॥

(प्रदीपः) समानाश्रय इति । तुल्यकालत्वादिति

भावः ॥ नोनावेत्यत्र बहुलग्रहणानुवृत्त्याऽनैमित्तिकोऽन्तरङ्गो लुक् प्रागेव प्रत्ययोत्पत्तेर्भवति ॥

(उद्योतः) ननु भिन्नाश्रययोरपि दीर्घवृद्ध्योरियायेत्यादौ बाध्यबाधकभावो दृष्ट इत्यत आह—तुल्यकालेति ॥ बहुलेति । यञोऽचि चेति चकारेण ॥ अन्तरङ्ग इति । प्राक्प्रवृत्तिकत्वमन्तरङ्गत्वम् । न हि तदाऽपवादप्रवृत्तिरिति भावः ॥

(आक्षेपभाष्यम्)

कथम्—स्यदः-प्रश्रथः-हिमश्रथः-जीरदानुः (ऋ. सं. ५।८३।१)-निकुचित इति?

(समाधाने भाष्यवार्तिकम्)

*** उक्तं शेषे ***

(भाष्यम्)

किमुक्तम्?

*** निपातनात्स्यदादिषु ***

*** रकि ज्यः सम्प्रसारणम् * इति ॥**

निकुचितेऽप्युक्तम् ।

किम्?

सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्येति ॥

न धातुलोप० ॥ ४ ॥

(प्रदीपः) **निकुचित इति ।** क्त्वसंयोगेन नलोपे सति उदुपधत्वमिति निमित्तमकित्त्वस्य न भवति ॥ यदि तर्ह्यकारलोपः क्रियते, तदा 'जङ्गमः' इत्यत्र तस्य स्थानिवद्भावादुपधालोपः प्राप्नोति । नैष दोषः, अनङीति प्रतिषेधात ॥ अनर्थकोऽयमङिति चेत्। उपधालोपस्यापि तर्ह्यप्राप्तिः, अजादौ प्रत्यये तस्य विधानात् ॥ ननु लोलुवादिषूवङादयः स्थानिवद्भावेन न सिध्यन्ति, तेषां स्थानिन्यदर्शनात्। संभवमात्रेणाप्यतिदेशो भवतीत्यदोषः ॥ ४ ॥

(उद्योतः) **अकित्त्वस्येति । उदुपधाद्भावादिकर्मणोरिति** विहितस्येत्यर्थः ॥ एवं चाकित्त्वाभावे **क्ङिति** चेत्येव निषेधः सिद्धो निकुचिते-इति भावः । **सन्निपातः**—संबन्धः । **तद्विघात** इति कर्मण्यण् ॥ **अजादौ प्रत्यये इति ।** यायायतेः क्तिचि यातिरित्यादौ आलोपानापत्तेर्यरेग्रहणस्य वैयर्थ्याच्च **चिन्त्यमेतत्** । अस्य समाधानं त्वसाभिरुक्तमेव ॥ **संभवेति ।** अत एव **न पदान्तसूत्रे यरेग्रहणं** चरितार्थम् । सत्यकारे यदि स्याधकारलोपस्तदा संभव उवङादेरिति भावः ॥ ४ ॥

(५ निषेधसूत्रम् ॥ १ । १ । ४ आ. २ ॥)

क्ङिति च ॥ १ । १ । ५ ॥

(अथ सप्तम्या निमित्तार्थत्वाधिकरणम्)

(९५ उपसंख्यानवार्तिकम् ॥ १ ॥)

॥ * ॥ क्ङिति प्रतिषेधे तन्निमित्तग्रहणम् ॥ * ॥

(व्याख्याभाष्यम्)

क्ङिति प्रतिषेधे तन्निमित्तग्रहणं कर्तव्यम् । क्ङिन्निमित्ते ये गुणवृद्धी प्राप्नुतस्ते न भवत इति वक्तव्यम् ॥

किम्प्रयोजनम्?

(प्रदीपः) **क्ङिति च ॥ ५ ॥ क्ङिति प्रतिषेध इति ।** इक इत्यनुवर्तते, गुणवृद्धी इति च । तत्र यदीक् क्ङितीत्यनेन विशेष्यते-क्ङिति परतो य इगिति तदा **'तस्मिन्निति निर्दिष्टे पूर्वस्य'** इति परिभाषोपस्थानान्निर्दिष्टग्रहणस्य चानन्तर्यार्थत्वात् 'चितं-स्तुतम्' इत्यादावेव निषेधः स्यात्, न तु भिन्नः-भिन्नवानित्यादाविति तन्निमित्तग्रहणं कर्तव्यम् ॥ यदा तु क्ङिद्ग्रहणं गुणवृद्धिविशेषणम्, तदा परसप्तम्या अप्रसङ्ग एव । न हि विहितयोर्निषेधः, अपि त्वनभिनिर्वृत्तयोरेवेति परिभाषाऽनुपस्थानान्निमित्तसप्तम्येव 'क्ङिति' इति । तन्निमित्ता हि तयोः प्रवृत्तिः ॥

(उद्योतः) **क्ङिति च ॥ ५ ॥ तत्र यदीति ।** तस्मिन्नितिपरिभाषाऽनुग्रहायेत्यर्थः ॥ **यदा त्विति ।** निषेध्यत्वेन तयोः प्राधान्यादिति भावः ॥ **न हीति ।** अनभिनिर्वृत्ते पूर्वपरव्यवहारस्य कर्तुमशक्यत्वात्तदनुपस्थानम् । निर्वृत्तनिषेधे तु देवदत्तहन्तृहतन्यायेन चितमित्यादाविकः श्रवणं न स्यादिति भावः ॥ **निमित्तेति ।** अत्र **यस्य च भावेनेति** सप्तमी । सा च ज्ञापकत्वार्थिका । ज्ञापकत्वं च संबन्धं विनाऽनुपपन्नं सत् विधिशास्त्रक्लृप्तनिमित्तत्वमादाय पर्यवस्यति । एवञ्च निमित्ततया क्ङित्ज्ञाप्ये गुणवृद्धी नेत्यर्थः । तदाह—**क्ङिन्निमित्ता हि तयोः प्रवृत्तिरिति** ॥ केचित्तु-**सिद्धसाध्यसमभिव्याहारन्यायेन** निमित्तत्वं फलति-**इत्याहुः** ॥ **परे तु**—क्ङितीत्येतत् गुणवृद्धिविशेषणमेव । भवनक्रियातदभावयोरमूर्तत्वेन क्ङित्परत्वासंभवात्। इक इत्यस्याप्यनुवृत्त्यनुक्तेः । अनुवृत्तावपि तस्य शब्दपरत्वात् । तस्मान्निमित्तग्रहणाभावे क्ङितीति सप्तम्या **'निर्दिष्टे पूर्वस्य'** इत्युपस्थित्या क्ङिति अव्यवहिते पूर्वस्य ये गुणवृद्धी प्राप्नुतस्ते नेत्यर्थः । **अनुवादे परिभाषा नोपतिष्ठत** इति त्विको **गुणवृद्धी अचश्चे**तिसूत्रद्वयविषयमेवेत्युक्तम् । भाष्ये तस्य निषेधस्यानुपलम्भाच्च। तद्वक्ष्यति—भाष्ये—**क्ङित्यनन्तरो गुणभाव्यस्तीति।** निमित्तग्रहणे तु तत्सामर्थ्यात्परिभाषाऽनुपस्थानम्, तत्प्रत्याख्याने तु लिङ्गादिना तदनुपस्थानम्॥ संभवन्त्यां परसप्तम्यां **'यस्य च–'** इति सप्तम्या असंभवाच्च, **उपपदविभक्ते**रिति न्यायात् ॥ **सिद्धसाध्यसमभिव्याहारन्याय**स्यापि **तस्मिन्निति**शास्त्रेण बाध एव ॥ अत एव निमित्तग्रहणप्रयोजनावसरे हत इत्युदाहरिष्यति । कैयटोक्तरीत्या इक्पदानुवृत्तावेव **निमित्तग्रहण**मिति वार्तिकस्योक्तिसंभवेन तत्प्रयोजनदानानुक्तिसंभवः स्पष्ट एवेत्याहुः ॥

(९६ प्रयोजनवार्तिकम् ॥ २ ॥)

॥ * ॥ उपधारोरवीत्यर्थम् ॥ * ॥

(भाष्यम्)

उपधार्थं रोरवीत्यर्थं च ॥

उपधार्थं तावत्—भिन्नः, भिन्नवान् ॥

किं पुनः कारणं न सिध्यति ?

क्ङितीत्युच्यते । तेन यत्र क्ङित्यनन्तरो गुणभाव्यस्ति तत्रैव स्यात्—चितम्, स्तुतम् । इह तु न स्यात्—भिन्नः, भिन्नवानिति ॥

(प्रदीपः) उपधारोरवीत्यर्थमिति । उपधाया अपीकः प्रतिषेधार्थम्, रोरवीतेर्यङ्निमित्तप्रतिषेधनिवृत्त्यर्थम् । अत्र हि तिव्निमित्तो गुणः, न यङ्निमित्तः ॥

(उद्द्योतः) उपधाया अपीति । उपधायां रोरवीतौ चार्थः= प्रयोजनं-प्रवृत्तिनिवृत्तिभ्यां प्रतिषेधो यस्य तत्, तन्निमित्तग्रहणमिति भाष्यार्थ इति भावः ॥ उपधारोरवीतिभ्यामिति-उपधारोरवीत्यर्थम्-इति अर्थेन नित्यसमास इत्यन्ये ॥

(प्रथमप्रयोजनबाधकभाष्यम्)

ननु च-यस्य गुण उच्यते, तत् क्ङित्परत्वेन विशेषयिष्यामः । पुगन्तलघूपधस्य च गुण उच्यते । तच्चात्र क्ङित्परम् ॥

(प्रदीपः) ननु चेति । आकाङ्क्षया 'पुगन्तलघूपधस्य' इति सन्निधानं मन्यते । तथाहि-'क्ङिति गुणवृद्धी न भवतः' इत्युक्ते 'कस्य' इत्याकाङ्क्षायां 'यस्य प्राप्ते' इत्यस्ति पुगन्तलघूपधस्यापेक्षा ॥ अथवा क्ङितीति प्रत्ययग्रहणात्प्रत्ययेनाङ्गं सन्निधाप्यते । ततश्च क्ङिति 'भिन्नं' इत्यादौ लघूपधस्यानन्तर्यात्सिद्धो निषेधः ॥

(उद्द्योतः) नन्वसंनिहितं पुगन्ताङ्गादि कथं तत्परत्वेन विशेष्यमत आह—आकाङ्क्षयेति ॥ ननु निषेध्ये गुणवृद्धी प्रति क्ङित्परेऽङ्गं निषेधविषयं प्रति चाकाङ्क्षा, नाङ्गं प्रतीत्यत आह—अथवेति । निषेध्यगुणादेरप्रत्यये क्ङित्प्रसङ्गेन प्रत्ययग्रहणमिति भावः ॥ एवं च प्रत्ययस्याङ्गांशे उत्थिताकाङ्क्षत्वात्तस्यैव तद्विशेषणमिति भावः ॥

(प्रथमप्रयोजनसाधकभाष्यम्)

पुगन्तलघूपधस्येति नैवं विज्ञायते—पुगन्तस्याङ्गस्य लघूपधस्य चेति ।

कथं तर्हि ?

पुकि अन्तः-पुगन्तः । लघ्वी उपधा-लघूपधा । पुगन्तश्च लघूपधा च पुगन्तलघूपधं, पुगन्तलघूपधस्येति ॥ अवश्यं चैतदेवं विज्ञेयम् । अङ्गविशेषणे हि सतीह प्रसज्येत—भिनत्ति, छिनत्तीति ॥

(प्रदीपः) लघूपधेति । ततश्च समुदायस्यानिर्देशादवयवस्य चेक्को व्यवधानात्तदवस्थैवाप्राप्तिरित्यर्थः ॥

(उद्द्योतः) आद्यव्याख्यायां परिहारभाष्यं योजयति—ततश्च समुदेति ॥ द्वितीये त्विदं बोध्यम्—नाक्षिप्तविशेषणत्वं न्याय्यमिति ॥ भाष्ये—अङ्गविशेषणे हीति । पुगन्तलघूपधस्येत्यस्य बहुव्रीहिणाऽङ्गविशेषणत्वे-इत्यर्थः ॥

(द्वितीयप्रयोजनसमन्वयभाष्यम्)

'रोरवीत्यर्थः' । त्रिधा बद्धो वृषभो रोरवीति ॥ (ऋ. ४।५८।३)

(आक्षेपभाष्यम्)

यदि तन्निमित्तग्रहणं क्रियते शचङन्ते दोषः-रियति, पियति, धियति, प्राद्रुद्रुवत्, प्रासुस्रुवत्-अत्र न प्राप्नोति ॥

(प्रदीपः) तन्निमित्तपक्षस्यापि दुष्टतामाह—शचङन्त इति । सार्वधातुकनिमित्तस्य गुणस्य निषेधेऽपि लघूपधलक्षणनिषेधाप्रसङ्ग इत्यर्थः ॥ रियतिपियतीति । 'रि-पि-गतौ' 'धि-धारणे' इति तुदादौ पाठः ॥

(उद्द्योतः) यदीत्यनेन न स्वपक्षस्योपादेयतोच्यते, किं तूभयोः साम्यमुच्यत इत्याह—तन्निमित्तपक्षस्यापीति ॥ सार्वधातुकनिमित्तस्य—शनिमित्तस्य ॥ लघूपधलक्षणस्य—तिव्निमित्तस्य ॥

(सिद्धान्तसमाधाने भाष्यवार्तिकम्)

* शचङन्तस्यान्तरङ्गलक्षणत्वात् *

(भाष्यम्)

अन्तरङ्गलक्षणत्वादियङुवङोः कृतयोरनुपधात्वात् गुणो न भविष्यति ॥

(उद्द्योतः) भाष्ये—अन्तरङ्गलक्षणत्वादिति । आभान्येनाच एव यत्रानन्तर्याश्रयणं तत्रैव नाजानन्तर्यं इति निषेधप्रवृत्तेस्तस्य अभावाच्चेति भावः ॥ नन्वदुद्रुवदित्यत्र 'सार्वधातुका-' इति गुणात्पूर्वं नित्यत्वाच्चङि 'द्विर्वचनेऽचि' इति निषेधादुवङभावे द्वित्वात्परत्वाल्लघूपधगुणो दुर्वार इति चेन्न । अन्तरङ्गत्वाद्द्वित्वस्यैव प्रवृत्तेः । ओणेर्ऋदित्करणेनोपधाकार्यस्य द्वित्वात्प्राबल्यबोधनेऽपि न क्षतिः । ज्ञापकस्य सजातीयापेक्षत्वेनोपधाकार्यस्य यत्र द्वित्वसमाननिमित्तता द्वित्वनिमित्तचङ्निमित्तता वा तत्रैव तत्प्राबल्यबोधनादित्याहुः ॥

(तन्निमित्तकग्रहणस्य निर्दोषतोपसंहारभाष्यम्)

एवं क्रियते चेदं तन्निमित्तग्रहणम्, न च कश्चिद्दोषो भवति ॥

(सूत्रार्थप्रदर्शनाय फलान्तरप्रदर्शकभाष्यम्)

इमानि च भूयस्तन्निमित्तग्रहणस्य प्रयोजनानि-हतः, हथः, उपोयते, औयत, लौयमानिः, पौयमानिः, नेनिक्ते-इति ॥

(प्रदीपः) हतो हथ इति । यथैव 'अदिप्रभृतिभ्यः शपः' इति शप् निवर्त्यते, एवमकारोऽपि निषेधेन निवर्त्येतेत्याशयः ॥ नन्विग्लक्षणोऽयं गुणो न भवतीति निषेधाप्रसङ्गः । सत्यम् । परिहारान्तरस्य सद्भावादेतन्नाश्रितम् ॥

(उद्द्योतः) भूयः—पुनरर्थे ॥ एवमकारोऽपीति । 'क्ङित्परे गुणवृद्धी न प्रयोक्तव्ये' इति सूत्रार्थः । तत्र यथा चितमित्यादावसतो गुणादेः प्रागभावः पाल्यते, एवं सतोऽपि निवृत्तिः साध्येत । सतोऽपि निवृत्तेरदिप्रभृतिभ्य इत्यादौ दृष्टत्वादिति भावः ॥ नन्विति । तथा चेक इत्यनुवृत्तिसामर्थ्यादसत एवाप्रयोगः प्रतिपाद्यत इति भावः ॥ (भाष्ये) नेनिक्त इति । अत्र निजां त्रयाणां गुणः श्लावित्यभ्यासस्य गुणः ॥

(फलान्तरप्रत्याख्यानभाष्यम्)

नैतानि सन्ति प्रयोजनानि । इह तावत्—हतो हथ इति । प्रसक्तस्याभिनिर्वृत्तस्य प्रतिषेधेन निवृत्तिः शक्या कर्तुम् । अयञ्च धातूपदेशावस्थायामेवाकारः ॥

(प्रदीपः) प्रसक्तस्येति । सामान्यलक्षणेन विशेषलक्षणापरामर्शेन यत्प्राप्तं पुनर्विशेषलक्षणपरामर्शात् यत् स्वरूपेणानभिनिर्वृत्तं तस्य निवृत्तिः क्रियते । परमार्थतस्तूत्सर्गापवादयोरप्येकवाक्यतायामप्राप्त्यनुमानं बाध इति सिद्धान्तः ॥ चितमित्यादौ च प्रसक्तानभिनिर्वृत्तगुणनिषेधे वचनस्य चरितार्थत्वाद्धतो हथ इति भूताकारनिवृत्तावस्थाव्यापारः । 'अदिप्रभृतिभ्यः' इत्यनेन तु गत्यन्तराभावात्सन्नेव प्रक्रियायां शब्निवर्त्यते ॥ यथैवं भवत इत्यादौ प्रसक्तोऽनभिनिर्वृत्त एव शवकारः कस्मादनेन न निवर्त्यते ? नैष दोषः, शब्भवतीत्यस्यां चोदनायां गुणरूपेणाचोदनान्नायं गुणनिषेधविषयः ॥

(उद्योतः) प्रसक्तत्वानभिनिर्वृत्तत्वयोर्विरोधमाशङ्क्याह—सामान्येति ॥ निवृत्तिः—अनभिनिर्वृत्तिः ॥ विहितप्रतिषिद्धयोर्विकल्पस्तर्हि स्यादत आह—परमार्थेति । गुणविध्येकवाक्यतया क्ङिद्भिन्नसार्वधातुकादौ गुण इत्यर्थात् क्ङिति तयोरप्राप्तिरेवेति भावः ॥ सा च पर्युदासविधया । यद्वा प्रसज्यप्रतिषेधेन वाक्यार्थबोधे तदंशे सामान्यशास्त्रजज्ञानस्याप्रामाण्यं कल्प्यते । एकवाक्यताफलसंपत्तेरस्त्वेकवाक्यतायामित्युक्तमिति द्रष्टव्यम् ॥ भूताकारेति । सिद्धाभावपरिपालनेनैव सिद्धौ असिद्धाभावविधाने गौरवादिति भावः ॥ प्रक्रियायामिति । वस्तुतस्तत्रापि लुग्द्वाराऽनुत्पत्तिरेवान्वाख्यायते—इति बोध्यम् ॥ नैष इति । एकान्ता अनुबन्धा इति भावः । अयमेव न्याय्य इति तस्यलोप इति सूत्रे वक्ष्यति ॥

(भाष्यम्)

इह च—उपोयते-औयत-लैयमानिः-पैयमानिरिति । बहिरङ्गे गुणवृद्धी, अन्तरङ्गः प्रतिषेधः । असिद्धं बहिरङ्गमन्तरङ्गे ॥

(प्रदीपः) उपोयत इति । वेञो यकि संप्रसारणे कृते उभयपदाश्रितत्वाद्बहिरङ्गो गुणः । औयत इत्यादौ बहिरङ्गाश्रयत्वाच्च वृद्धिर्बहिरङ्गा ॥

(भाष्यम्)

नेनिक्त इति । परेण रूपेण व्यवहितत्वान्न भविष्यति ॥

(प्रदीपः) नेनिक्ते इति । क्ङित्परत्वेनाङ्गस्य विशेषणादङ्गस्यात्र कार्यित्वात्पूर्वः पक्षः । उत्तरस्त्वभ्यासस्य कार्यित्वात्तस्य च परेण रूपेण व्यवधानादिति ॥

(उद्योतः) कार्यित्वादिति । अङ्गस्य गुणो भवति, स च तत्संबन्ध्यभ्यासेकः—इत्यर्थं इत्यभिमानः ॥ उत्तरस्त्विति । पक्ष इति शेषः ॥ क्ङित्परस्य यस्य गुणः प्राप्तस्तस्य नेति सूत्रार्थ इति भावः ॥

(तन्निमित्तग्रहणप्रत्याख्यानभाष्यम्)

उपधार्थेन तावन्नार्थः । धातोरिति वर्तते । धातुं क्ङित्परत्वेन विशेषयिष्यामः ॥

(प्रदीपः) धातुं क्ङित्परत्वेनेति । 'धातुलोपे' इत्यत्रोपसर्जनत्वेऽपि धातोर्धातुशब्दमात्रस्य स्वरितत्वादिहानुवृत्तिरित्यर्थः ॥

(उद्योतः) भाष्ये—धातुं क्ङिदिति । परत्वेन निर्दिष्टं यत् क्ङिदिति तद्धातुं प्रति विहितमिति विशेषयिष्यामः । तथा च धातुविहितं क्ङित् यतः कृतश्चित्परं तदवयवस्य गुणो नेति सूत्रार्थं इत्यर्थः ॥ तदूध्वनयन्नाह—मत्वा प्रश्न इति ॥

(आक्षेपभाष्यम्)

यदि धातुर्विशेष्यते, विकरणस्य न प्राप्नोति—चिनुतः, सुनुतः, लुनीतः, पुनीतः-इति ॥

(प्रदीपः) यदीति । क्ङित्यनन्तरस्य धातोर्गुणवृद्धी न भवत इति वाक्यार्थं मत्वा प्रश्नः ॥

(समाधानभाष्यम्)

नैष दोषः । विहितविशेषणं धातुग्रहणम्—धातोर्यो विहित इति ॥

(आक्षेपभाष्यम्)

धातोरेव तर्हि न प्राप्नोति ॥

(प्रदीपः) धातोरेवेति । धातोर्विहितस्य क्ङित्यनन्तरे नेति मत्वा प्रश्नः ॥

(समाधानभाष्यम्)

नैवं विज्ञायते—धातोर्विहितस्य क्ङितीति ।
कथं तर्हि ?
धातोर्विहिते क्ङितीति ॥

(प्रदीपः) धातोर्विहित इति । धातोर्विहिते क्ङित्यनन्तरो यो धातुर्विकरणो वा तस्य प्रतिषेध इत्यर्थः ॥

(उद्योतः) धातुर्विकरणो वेति । धातुना विहितविशेषणबललब्धमेतदुभयम् ॥

(समाधानान्तरभाष्यम्)

अथवा—कार्यकालं हि संज्ञापरिभाषं, यत्र कार्यं तत्र द्रष्टव्यम् । 'पुगन्तलघूपधस्य गुणो भवति' इत्युपस्थितमिदं भवति "क्ङिति न" इति ॥

(प्रदीपः) अथवेति । यत्र गुणवृद्धी विधीयेते तत्र 'क्ङिति न' इत्युपतिष्ठते—इत्येवमियं परिभाषा भवति । तत्र 'पुगन्तलघूपधस्य' इत्यत्रास्या उपस्थाने सति येन नाव्यवधानमिति भिन्नमित्यादौ निषेधो भविष्यति ॥

(उद्योतः) येन नेति । पुगन्तलघूपधेति तत्पुरुष इति भावः ॥ श्रुतत्वात्सार्वधातुकादिकं क्ङितीति च पुगन्तादीनामेव विशेषणमित्यभिमानः ॥

(समाधानान्तरभाष्यम्)

अथवा यदेतस्मिन्योगे क्ङिद्ग्रहणं तदनवकाशम्, तस्यानवकाशत्वात् गुणवृद्धी न भविष्यतः ॥

(प्रदीपः) अथवेति । मा भूत्परिभाषा, तथापि प्रतिषेधस्य प्रतिषेध्यापेक्षायां यावन्तो यादृशाः प्रतिषेद्धव्यास्तावन्ति प्रतिषेधसूत्राणीति पुगन्तलघूपधगुणे प्रतिषेध्येऽनवकाशः प्रतिषेधो व्यवहितेऽपि प्रवर्तते ॥ अथवा यथोद्देशपक्षाश्रयेण भाष्यम् । तथाहि—प्रधानान्यात्मसंस्काराय सन्निधीयमानानि गुणमेवं प्रयुञ्जते-इति 'यदेतस्मिन्' इत्युक्तम् ॥

(उद्योतः) प्रतिषेध्यापेक्षायामिति। गुणवृद्धिश्रुत्या तद्रूपप्रतिषेध्याकाङ्क्षायां यावद्गुणवृद्धिविधायकशास्त्रविषयकनिषेधवाक्यानां व्यक्तिपक्षे विनिगमनाविरहादुपप्लव इत्यर्थः॥ प्रधानानीति। अनेन तद्विषयकनिषेधोपप्लवे बीजं दर्शितमित्याहुः॥

(समाधानान्तरभाष्यम्)

अथवाऽऽचार्यप्रवृत्तिर्ज्ञापयति—'भवत्युपधालक्षणस्य गुणस्य प्रतिषेधः' इति। यदयं "त्रसिगृधिधृषिक्षिपेः क्नुः" "इको झल्, हलन्ताच्च" इति क्नुसनौ कितौ करोति।

कथं कृत्वा ज्ञापकम्?

कित्करणे एतत्प्रयोजनम्—गुणः कथं न स्यादिति।

यदि चात्र गुणप्रतिषेधो न स्यात्, कित्करणमनर्थकं स्यात्। पश्यति त्वाचार्यः—भवत्युपधालक्षणस्य प्रतिषेध—इति, ततः क्नुसनौ कितौ करोति॥

(प्रदीपः) अथवेति। लिङ्गान्निर्दिष्टाङ्गविकला 'तस्मिन्निति' परिभाषोपतिष्ठत इत्यर्थः॥ अनेकपरिहारोपन्यासो न्यायव्युत्पादनार्थः॥

(उद्योतः) अङ्गविकलेति। पूर्वस्य परस्य वेति सन्देहेन तदुपस्थितेरिति भावः॥ न चैवं नेनिक्ते इत्यत्रापि निषेधः स्यात्, येननेति न्यायेनैकवर्णव्यवधाने एव निषेधप्रवृत्तेर्बोधनात्॥ न्यायव्युत्पादनेति। न्यायव्युत्पत्तिः—तत्प्रतिपत्तिः। ओतॄणां तदुत्पादनायेत्यर्थः॥ भाष्ये—हलन्ताच्चेति। नन्वेतद्विहितकित्त्वस्य न ज्ञापकत्वम्। दिदृक्षतीत्यादावमागमनिषेधेन धिप्सतीत्यादौ नलोपेन च चारितार्थ्यात्। इको झलित्यपि न, तद्विषये इकः कित्परत्वस्यैव संभवादिति चेत्। न, "सृजिदृशोर्झल्यमकिति" "इको झल्" "दम्भेः" इति क्रमन्यासेन सिद्धे सामान्यतोऽतिदेशस्य गुणप्रतिषेधार्थत्वेन ज्ञापकसाम्राज्यात्। स्वपिदमुषां वस्वासनोर्गृहग्धगुधकुषक्लिशां कवः कित्त्वविधानं च ज्ञापकं बोध्यम्॥

(द्वितीयप्रयोजनप्रत्याख्यानभाष्यम्)

रोरवीत्यर्थेनापि नार्थः। 'क्ङिति' इत्युच्यते, न चात्र क्ङितं पश्यामः॥

(आक्षेपभाष्यम्)

प्रत्ययलक्षणेन प्राप्नोति।

(समाधानभाष्यम्)

"न लुमता तस्मिन्" इति प्रत्ययलक्षणप्रतिषेधः।

अथापि "न लुमताङ्गस्य" इत्युच्यते, एवमपि न दोषः।

कथम्?

न लुमता लुप्तेऽङ्गाधिकारः प्रतिनिर्दिश्यते।

किं तर्हि?

योऽसौ लुमता लुप्यते तस्मिन्यदङ्गं तस्य यत्कार्यं तत्र भवतीति॥

अथाप्यङ्गाधिकारः प्रतिनिर्दिश्यते, एवमपि न दोषः।

कथम्?

"कार्यकालं संज्ञापरिभाषम्" यत्र कार्यं तत्र द्रष्टव्यम्। सार्वधातुकार्धधातुकयोर्गुणो भवतीति उपस्थितमिदं भवति "क्ङिति न" इति॥

(उद्योतः) अङ्गाधिकार इति। स्वरितलिङ्गासङ्गेनेति भावः॥ कार्यकालमिति। तथा च तत्रोपस्थितत्वादिदमप्याङ्गम्, अङ्गाधिकारस्यैकवाक्यतापन्नत्वादिति भावः॥ स्वरितत्वासङ्गवशात्तदधिकारपठितमिव तदधिकारस्थैकवाक्यतापन्नमपि गृह्यते—इति तात्पर्यम्॥ निषेधेऽपि परिभाषासादृश्यात्परिभाषात्वमुक्तम्। सादृश्यं च निषेध्याकाङ्क्षया तदेकवाक्यतामात्रेणेति बोध्यम्॥

(समाधानान्तरभाष्यम्)

अथवा छान्दसमेतत्, दृष्टानुविधिश्छन्दसि भवति॥

(उद्योतः) छान्दसमिति। यङोऽचि चेति चेन बहुलं छन्दसीत्यनुकृष्य यङो लुग्विधानादित्यर्थः। न च हुश्नुवोः—'इति सूत्रस्थेन हुश्नुवोरित्यस्य भाषायां यङ्लुक्सत्ताज्ञापकपरभाष्येणोवर्णान्तेभ्यो यङ्लुक् भाषायामप्यस्तीति लभ्यते। अन्यथा ज्ञापितेऽप्यचारितार्थ्यं स्पष्टमेवेति वाच्यम्। तत्प्रामाण्येनाजादौ क्ङिति क्वचित्तत्सत्त्वाङ्गीकारेऽपि सर्वत्र भाषायां तत्सत्त्वे मानाभावात्। तत्रत्यभाष्यस्यैकदेश्युक्तित्वाच्च॥

(समाधानान्तरभाष्यम्)

अथवा बहिरङ्गो गुणोऽन्तरङ्गः प्रतिषेधः। "असिद्धं बहिरङ्गमन्तरङ्गे"॥

(प्रदीपः) बहिरङ्ग इति। ततश्चासिद्धत्वादसत्त्वान्निषेधानुपपत्तिरित्यर्थः॥

(उद्योतः) गुणो बहिरङ्ग इति। गुणस्य बहिरङ्गता, बहिर्भूतसार्वधातुकाश्रयत्वात्॥ नन्वसिद्धस्यानिष्पन्नस्यैव निषेधः क्रियते, तत्राह—असत्त्वादिति। शास्त्रासिद्धत्वादत्रासत्त्वबुद्ध्या प्रतियोगिज्ञानाभावान्निषेधानुपपत्तिरिति भावः॥

(समाधानान्तरभाष्यम्)

अथवा पूर्वस्मिन्योगे यदार्धधातुकग्रहणं, तदनवकाशम्। तस्यानवकाशत्वात् गुणो भविष्यति॥

(प्रदीपः) अथवेति। ननु बहुव्रीह्यर्थमुभयविशेषणायार्धधातुकग्रहणं स्यादिति कथमनवकाशत्वम्? उच्यते—विनाप्यार्धधातुकग्रहणेन बहुव्रीहिर्लभ्यते। यथा 'एकाचो द्वे' इत्यत्र। रोरवीतीत्यत्रानैमित्तिकत्वाल्लोपस्य गुणनिषेधः पूर्वेण न प्राप्नोतीत्यार्धधातुकग्रहणसामर्थ्यात्सूत्रान्तरप्राप्तोऽपि निषेधो बाध्यत इत्यर्थः॥ यङ्निमित्तश्च निषेधोऽन्तरङ्गत्वाद्बाध्यते, न सार्वधातुकनिमित्त इति रोरुत इत्यादौ निषेधो भवत्येव॥ एतच्च छान्दसत्वमभ्युपेत्य यङ्लुको भाष्यकारेणोक्तम्॥ भाषाविषयत्वे

तु यङ्लुको बहूनि प्रयोजनान्यार्धधातुकग्रहणस्य संभवन्ति। तोतोर्ति, तोथोर्ति, दोदोर्ति, दोधोर्ति, जोहोर्ति, मोमोर्ति-इत्यादिषु तुर्वीथुर्वीदुर्वीधुर्वीत्यादिभ्यो यङ्लुकि तिपि छकारवकारयोः 'राल्लोपः' इति लोपे कृतेऽसत्यार्धधातुकग्रहणे बहुव्रीहावप्याश्रिते 'न धातुलोप-' इति गुणनिषेधः प्राप्नोति, स मा भूदित्येवमर्थमार्धधातुकग्रहणं स्यात्। अनेन चात्र व्यवधानान्नास्ति निषेध इति सति प्रयोजने कथमनवकाशं स्यात् ॥

(उद्योतः) उभयविशेषणाय बहुव्रीह्यर्थमित्यन्वयः ॥ यथेति। प्रथमस्येत्येतत्कर्मधारयेऽपि विशेष्यं शक्यं कर्तुमिति न तत् बहुव्रीहित्वगमकमिति भावः ॥ ननु सूत्रान्तरप्राप्तनिवृत्तिः कथं ? तत्राह—सामर्थ्यादिति। अयमाशयः—आर्धधातुके-इति योगो विभज्यते, धातुलोप इति वर्तते षष्ठीतत्पुरुषश्च। एवं च धात्वेकदेशलोपे सति प्रत्यासत्त्याऽन्तरङ्गतया च लुप्तधात्वेकदेशनिमित्तो गुणवृद्धिनिषेधश्चेदार्धधातुक एव-इति नियमस्तत्सामर्थ्यात्-इति ॥ तत् ध्वनयन्नाह—यङ्निमित्तश्चेति ॥ भाषेति। हुश्नुवोः सार्वधातुक इत्यत्र हुश्नुग्रहणादिति भावः ॥ इत्यादिभ्य इति। आदिना-हुर्च्छामुर्छे ॥ राल्लोप इति। तत्र हि क्विझलोरिति नानुवर्तते। तदनुवृत्तिपक्षे तोतोर्मीत्याद्युदाहरणम् ॥ नन्वेवमपि क्ङिति चेति निषेधोऽत्र दुर्वार इति तद्वारणं विनाऽस्य चारितार्थ्यं कथमत आह—अनेनेति। बहिरङ्गराल्लोपस्यान्तरङ्गे यङाश्रये प्रतिषेधे कार्येऽसिद्धत्वाद् द्वाभ्यां व्यवधानात्तदप्राप्तिः। सनः कित्त्वेन तु एकव्यवधानमेवाश्रितमिति भावः ॥ वस्तुतस्तु भाष्यप्रामाण्यादेषां प्रयोगाणां लोकेऽभाव इत्येवाश्रयणीयम् ॥

(आक्षेपभाष्यम्)

इह कस्मान्न भवति—'लैगवायनः' 'कामयते' ?

(सिद्धान्तसमाधाने भाष्यवार्तिकम् ॥)

* तद्धितकाम्योरिक्प्रकरणात् *

(भाष्यम्)

इग्लक्षणयोर्गुणवृद्ध्योः प्रतिषेधः। न चैते इग्लक्षणे ॥

(प्रदीपः) इग्लक्षणयोरिति। इक इत्येवं ये गुणवृद्धी तयोर्निषेध इत्यर्थः ॥

(उद्योतः) नन्विग्लक्षणयोरित्युक्तावपि लैगवायने इक्स्थानिकत्वेनेग्लक्षणत्वात्स्यादेव गुणनिषेधोऽत आह—इक इतीति। अर्थाधिकारानुरोधेन पदपरमेव 'इकः' इति सम्बध्यत इति भावः ॥

इति निमित्तार्थत्वनिराकरणम् ॥

(अथ स्थानिवत्त्वप्राप्तदोषवारणम्)

(१२८ आक्षेपवार्तिकम् ॥ ४ ॥)

॥ * ॥ लकारस्य ङित्त्वादादेशेषु स्थानिवत्प्रसङ्गः ॥ * ॥

(भाष्यम्)

लकारस्य ङित्त्वादादेशेषु स्थानिवद्भावः प्राप्नोति—अचिनवम्, असुनवम्, अकरवम् ॥

(प्रदीपः) लकारस्येति। अनुबन्ध इत्संज्ञकत्वाल्लोपात्स्थानिनि न सन्निधीयत इति 'अनल्विधौ' इति निषेधो न प्रवर्तते। 'पिन्ङिन्न भवति' 'ङित्पिन्न भवति' इति भाष्यकारस्य कल्पना, न वार्तिककारस्येति दोषोपन्यासः ॥

(उद्योतः) लोपादिति। पदार्थोपस्थितिकाल एवान्तरङ्गत्वाल्लोपप्रवृत्तिरिति भावः ॥ पिन्ङिन्नेति। सार्वधातुकमित्यत्रापिदिति योगविभागेन प्रसज्यप्रतिषेधेनायमर्थो लभ्यते। तत्र योगविभागसामर्थ्यात् स्थानिवत्त्वप्राप्ता अन्या वा ङित्त्वप्राप्तिः सर्वा प्रतिषिध्यत इत्याशयः ॥ भाष्ये—स्थानिवद्भावः प्राप्नोतीति। तथा चाचिनवमित्यादौ गुणनिषेधप्रसङ्ग इति भावः ॥

(एकदेशिसमाधानभाष्यवार्तिकम् ॥)

* लकारस्य ङित्त्वादादेशेषु स्थानिवद्भावप्रसङ्ग इति चेत् यासुटो ङिद्वचनात्सिद्धम् *

(व्याख्याभाष्यम्)

यदयं यासुटो ङिद्वचनं शास्ति तज्ज्ञापयत्याचार्यः—न ङिदादेशा ङितो भवन्तीति ॥

(आक्षेपभाष्यम्)

यद्येतज्ज्ञाप्यते, कथं "नित्यं ङितः" "इतश्च" इति ?

(प्रदीपः) कथं नित्यं ङित इति। ननु ङितो लकारस्येति तत्रार्थः स्थितः, न तु ङित आदेशस्येति। अन्यथा पचावः पचन्तीति लोपः स्यात्। एवं मन्यते—यासुटो ङित्त्वेन ज्ञापकेन स्थानिनि एव लकारस्य ङिद्व्यपदेश उच्छिद्यते। ङकारोच्चारणं तु 'लुङ्लङ्लृङ्क्षु' इत्यादौ विशेषणार्थं स्यात् ॥

(उद्योतः) ननु ङित इति। तथा च न स्थानिवत्त्वेन ङित्त्वं प्राप्यमिति भावः ॥ ङिद्व्यपदेश इति। स्थानिलसंबन्धिङत्संज्ञाभाव एव ज्ञाप्यते। लस्येत्यस्य लघटितस्येति व्याख्या कार्येत्यर्थः ॥

(समाधानभाष्यम्)

ङितो यत्कार्यं तद्भवति, ङिति यत्कार्यं तन्न भवतीति ॥

(प्रदीपः) ङितो यदिति। स्थानिवद्भावेन लादेशे ङिति

यत्कार्यं पूर्वस्य तन्न भवतीति ज्ञाप्यते, न तु स्थानिन एव ङिद्व्यपदेश उच्छिद्यते । अन्यथा 'नित्यं ङितः' इत्येतन्निर्विषयं स्यादित्यर्थः ॥

(उद्द्योतः) यत्कार्यं पूर्वस्येति । प्राप्तमिति शेषः ॥ न त्विति । प्रथमोपस्थितेस्संज्ञाशास्त्रबाधापेक्षया स्थानिवत्त्वबाध एव युक्त इति भावः ॥ युक्त्यन्तरमप्याह—अन्यथेति । लङ्लिङादेर्ङिद्व्यपदेशस्योच्छिन्नत्वादित्यर्थः । ङित आदेशस्येत्यर्थस्तु नेत्युक्तमेव ॥

(आक्षेपभाष्यम्)

किं वक्तव्यमेतत् ?

(समाधानभाष्यम्)

न हि ।

(आक्षेपभाष्यम्)

कथमनुच्यमानं गंस्यते ?

(समाधानभाष्यम्)

यासुट एव ङिद्वचनात् । अपर्याप्तश्चैव हि यासुट् समुदायस्य ङित्त्वे । ङितं चैनं करोति, तस्यैतत्प्रयोजनम्-ङितो यत्कार्यं तद्यथा स्यात्, ङिति यत्कार्यं तन्मा भूदिति ॥ क्ङिति च ॥ ५ ॥

(प्रदीपः) **यासुट एवेति** । ङितो यत्कार्यं तद्यासुटो न किंचिदतिदेष्टव्यमस्ति, किंतु ङिति यत्कार्यं विधीयते संप्रसारणादिकं तदतिदिश्यते । तच्चेत्स्थानिवद्भावात्स्यादतिदेशोऽनर्थकः स्यादित्यतिदेशः क्रियमाणो ङिति यत्कार्यं तदभावस्यैव ज्ञापकः ॥ **अपर्याप्तश्चेति** । समुदायस्य ङिद्व्यपदेशे कर्तव्ये यासुडसमर्थः । यासुट एव ह्यनेन ङित्त्वं क्रियते, न समुदायस्य । 'क्ङिति च' इत्यत्र तन्निमित्तग्रहणस्य प्रत्याख्यातत्वादगुणनिमित्तेऽपि यासुटि ङिति गुणनिषेधः सिध्यति । यदि समुदाये स्थानिवद्भावेन ङित्कार्यमभविष्यत्, यासुटो ङित्त्वं न व्यधास्यत् । विहितं ज्ञापयति—ङिति यत्कार्यं तत्स्थादेशे न भवतीति ॥ **केषांचित्पाठः**—'अपर्याप्तश्चैव हि' इति । तत्रावयवङित्त्वद्वारेण समुदायस्य ङित्त्वं विधीयत इति व्याख्येयम् । एवं हि क्ङितीति निमित्तसप्तमीपक्षेऽपि गुणनिषेधः सिद्ध्यति । अस्मिन्पक्षे 'ङितं चैनं करोति' इति समुदायः परामृश्यते ॥ ५ ॥

(उद्द्योतः) **तदभावस्यैवेति** । ज्ञापकस्य सजातीयापेक्षत्वादिति भावः । भाष्ये—**यासुट एवे**त्यस्य 'न समुदायस्य' इत्यर्थः, एवस्यावधारणार्थत्वात् । यदि समुदायस्य ङित्त्वं स्यात्तदा ङितो यत्कार्यं तदपि तत्र प्राप्तियोग्यमिति तदभावमपि ज्ञापयेत् । तथा हि—नित्यं ङित इत्यादेर्ङित आदेशस्येत्येवार्थः । पचावः पचन्तीत्यादौ तु न दोषः, **सार्वधातुकमपि**दित्यत्रानुवृत्तङिदित्यस्य लुप्तसप्तमीकतया ङितीव कार्यस्यैवातिदेशादिति भावः ॥ न च यासुटि ङिति किंचित् कार्यं प्राप्नोति' तन्निमित्तग्रहणेन निषेधाप्राप्तेरिति **भाष्यम्** । संप्रसारणप्राप्तेः । न हि तत्र प्रत्यय इत्यस्तीत्याहुः ॥ नन्ववयवे कृतस्य लिङ्गस्य समुदायविशेषकत्वात् 'यासुट् ङित्' इत्युक्तावपि समुदायस्य ङित्त्वं भवत्येव । अत एव तन्निमित्तग्रहणेऽपि निषेधः सिध्यति । तच्च स्थानिवत्त्वेन सिद्धमिति व्यर्थं ङित्त्वं स्थानिनो ङिद्व्यपदेशोच्छेदेऽपि ज्ञापकं स्यात्, ङितो यत्कार्यं तदभावस्यापि वा ज्ञापकं स्यादत आह—भाष्ये-**अपर्याप्तश्चैवेति** । अस्य ङित्त्वस्य केवले आगमे संप्रसारणविधानेन चरितार्थत्वात् । अवयवेऽचरितार्थस्यैव च समुदायविशेषकत्वम् । अत एव 'पठिता विद्या' इत्यादौ ङीप् नेति भावः ॥ **ङितं चैनमिति** । अवयवमित्यर्थः ॥ **यासुट एव हीति** । यासुट् ङिदिति सामानाधिकरण्यात् । यासुट्पदस्य स्वविधानाय स्वरूपपरस्य ङित्त्वसंबन्धे तदादौ लक्षणायां मानाभाव इति भावः ॥ **प्रत्याख्यातत्वा**दिति । स्वरितत्वप्रतिज्ञानात्समुदायगतनिमित्तत्वस्यावयवे आरोपादपि निषेधप्रवृत्तिरित्यन्ये ॥ **यदि समुदाये** इति । ननु स्थानिवत्त्वेन समुदायस्य ङित्त्वे यासुटः कथं ङित्त्वमिति चेत् । न । तन्ङित्त्वसाध्यफलस्य तावताऽपि सिद्धेरिति भावः ॥ **केषांचिदि**ति । अत्र पाठे—**यासुट एवे**त्येवकारः प्रसिद्ध्यर्थकः । केवलयासुटो ङित्त्वं व्यर्थ, गुणनिषेधे तन्निमित्तग्रहणात् । संप्रसारणमपि धात्वाक्षिप्ते प्रत्यये एव । एवं च सामर्थ्यात्समुदायविशेषकं तदिति भावः ॥ **ङितं चैनमिति** । स्थानिवत्त्वेन ङित्त्वे सिद्धेऽपीति शेषः ॥ **ङितो यत्कार्यमित्यादि** । ज्ञापकस्य सजातीयापेक्षत्वादिति भावः ॥ न हि यासुड्विशिष्टस्य ङित्त्वप्रयुक्तं किंचिदनेन ङित्त्वेन प्राप्नोति । नित्यं ङित इत्यस्य च ङितो लस्येत्येवार्थात् । 'आदेशस्य ङितः' इत्यर्थे तु दोष उक्त एव । सार्वधातुकमित्यादौ ङिदित्यस्य उभयेऽपि प्रथमादर्शनेन सप्तम्यन्तताया अन्याय्यत्वादिति भावः ॥ नन्विदं ङित्त्वं स्तुयादिस्यादावनिग्लक्षणवृद्धिबाधनार्थं, चिनुयुरित्यादौ जुसि चेति निषेधार्थं च चरितार्थमिति चेत् । न, ङिच्च पिन्नेति भाष्योक्तकल्पनयैव सिद्धेः । एतदर्थमेव हि भाष्ये तत्स्वीकारः ॥ यत्तु—संज्ञापूर्वकविधेरनित्यत्वेन वृद्धिवारणम् । अत एव 'उत औत्' इति नास्तौतीति । तन्न । अस्यार्थस्य भाष्यास्पृष्टत्वात् । ज्ञाजनोर्जेत्यस्याङ्गवृत्तपरिभाषाज्ञापकत्वपरभाष्यासङ्गतेश्च । अनयैवान्यथासिद्धेः । जुसि चेत्यत्र प्रसज्यस्याचीत्यतोऽचीत्यनुवर्त्याजादौ जुसि गुणविधानान्न चिनुयुरित्यत्र दोषः ॥ एवं च अत्रत्यपूर्वपक्षसिद्धान्तावेकदेशिन एवेति बोध्यम् ॥ ५ ॥

(५ निषेधसूत्रम् ॥ १ । १ । ६ आ. ३ ॥)

दीधीवेवीटाम् ॥ १ । १ । ६ ॥

(सूत्रप्रयोजनाधिकरणम्)

(आक्षेपभाष्यम्)

किमर्थमिदमुच्यते ?

(समाधानभाष्यम्)

गुणवृद्धी मा भूतामिति । आदीध्यनम्, आदीध्यकः । आवेव्यनम्, आवेव्यकः-इति ॥

(दीधीवेवीप्रत्याख्यानभाष्यम्)

अयं योगः शक्योऽकर्तुम् ।

कथम् ?

(१३० सिद्धान्तवार्तिकम् ॥ १ ॥)

॥ * ॥ दीधीवेव्योश्छन्दोविषयत्वात् दृष्टानुविधित्वाच्च छन्दसश्छन्दस्यदीधेद्-दीधयुरिति च गुणदर्शनादप्रतिषेधः ॥*॥

(भाष्यम्)

'दीधीवेव्योश्छन्दोविषयत्वात्' । दीधीवेव्यौ छन्दोविषयौ । 'दृष्टानुविधित्वाच्छन्दसः' । 'दृष्टानुविधि'श्छन्दसि भवति । 'छन्दसि अदीधेददीधयुरिति च गुणस्य दर्शनादप्रतिषेधः' । अनर्थकः प्रतिषेधः-अप्रतिषेधः । "प्रजापतिर्वै यत्किञ्चिन्मनसाऽदीधेत्," "होतार्य वृतः कुपयन्नदीधेत् (ऋ. सं. १०।९८।७)" "अदीधयुर्दाशराज्ञे वृतासः (ऋ. सं. ७।३३।५)" ॥

(प्रदीपः) दीधीवेवी० ॥६॥ छन्दोविषयत्वादिति । भाषायामेतयोः प्रयोगाभावात् ॥ दृष्टानुविधित्वाच्चेति । यद्यपि भाषायामपि दृष्टमेवानुविधीयते 'सिद्धे शब्दार्थसंबन्धे' इति न्यायात्, तथाप्यादीध्यनमित्यादिप्रयोगश्छन्दसि नास्ति । दृष्टस्यैव छन्दस्यनुविधानमित्यर्थः, न छन्दस्येव दृष्टानुविधानमिति । अथवा 'दृष्टानुविधिः' इत्यस्यायमर्थः—गुणश्छन्दसि दृश्यते न तु सर्वत्र गुणनिषेध इति ॥ अदीधेदिति । लङ्, व्यत्ययेन तिप् ॥ अदीधयुरिति । 'जक्षित्यादयः षट्' इत्यभ्यस्तत्वाज्जुसादेशो झेः ॥

(उद्योतः) दीधी० ॥६॥ भाषायामिति । अनन्यभावो हि विषयशब्दार्थ इति भावः ॥ दृष्टस्यैवेति । भाषायां तु संप्रति प्रयोगेऽदृष्टस्यापि व्याकरणान्तरानुसारेण शिष्टप्रयोगादिना वाऽवगतसाधुत्वस्याप्यनुविधानमित्यर्थः ॥ एवं च वेद आदीध्यनमित्यादिलक्ष्याभावादसंभवदुक्तिकं सूत्रमिति भावः ॥ अथवेति । एवं च लक्षणसाम्याशिप्रतिपादकं भाष्यमिति भावः ॥ व्यत्ययेनेति । दीधीङो ङित्वात् ॥ परस्मैपदोपलक्षणं तिप्-इति ॥

(आक्षेपभाष्यम्)

भवेदिदं युक्तमुदाहरणम्—अदीधेदिति । इदं त्वयुक्तम्—अदीधयुरिति । अयं जुसि गुणः प्रतिषेधविषय आरभ्यते, स यथैव "क्ङिति च" इत्येतं प्रतिषेधं बाधते, एवमिममपि बाधेत ॥

(समाधानभाष्यम्)

नैष दोषः, जुसि गुणः प्रतिषेधविषय आरभ्यमाणस्तुल्यजातीयं प्रतिषेधं बाधते ।

कश्च तुल्यजातीयः प्रतिषेधः ?

यः प्रत्ययाश्रयः । प्रकृत्याश्रयश्चायम् ॥

(प्रदीपः) प्रकृत्याश्रयश्चायमिति । ततश्चान्तरङ्गत्वादनेनैव भाव्यमित्यर्थः ॥

(उद्योतः) अन्तरङ्गत्वादिति । नन्वेवं बहिरङ्गस्य जुसि गुणस्य कथमनेन निषेध इति चेत् । न । सर्वस्यापि गुणस्य प्रत्ययाश्रयत्वेन बहिरङ्गतयाऽन्तरङ्गनिषेध्याभावादिति भावः ॥

(समाधानान्तरभाष्यम्)

अथवा-येन नाप्राप्ते तस्य बाधनं भवति । न चाप्राप्ते 'क्ङिति च' इत्येतस्मिन्प्रतिषेधे जुसि गुण आरभ्यते । अस्मिन्पुनः प्राप्ते चाप्राप्ते च ॥

(प्रदीपः) येन नाप्राप्त इति । कार्यविशेषचिन्तापेक्षायामयं न्यायः, न तु कार्यसामान्यं बाध्यमित्यस्यापेक्षायां न्यायावतारः ॥

(उद्योतः) सर्वत्रैतन्न्यायानाश्रयणे हेतुमाह—कार्यविशेषेति । यच्छब्देन तत्तद्रूपेण कार्याणां परामर्शादिति भावः ॥ केचित्तु—सामान्यचिन्ताविषयेऽप्येतं न्यायं योजयन्ति । तदा येनेत्यस्य स्वेतरेणेत्यर्थः ॥

(आक्षेपभाष्यम्)

यदि तर्ह्ययं योगो नारभ्यते, कथं-दीध्यदिति ?

(प्रदीपः) कथं दीध्यदिति । लेट्, तिप्, 'इतश्च लोपः परस्मैपदेषु' इतीकारलोपः । 'लेटोऽडाटौ' इत्यडागमः ॥

(१३१ सिद्धान्तसमाधानवार्तिकम् ॥ २ ॥)

॥ * ॥ दीध्यदिति च श्यन्व्यत्ययेन ॥ * ॥

(भाष्यम्)

दीध्यदिति श्यन् एष व्यत्ययेन भविष्यति ॥

(प्रदीपः) श्यन्व्यत्ययेनेति । श्यनो ङित्वाद्गुणाभावः । 'यीवर्णयोर्दीधीवेव्योः' इतीकारलोपः ॥ क्वचित्तु 'शो व्यत्ययेन' इति पाठः । तत्र शस्य ङित्वाद्गुणाभावः । 'एरनेकाचः-' इति यणादेशः ॥

(उद्योतः) [क्वचित्तु शो व्यत्येति पाठः ॥]

(एकदेशिप्रत्याख्यानभाष्यम्)

इटश्चापि ग्रहणं शक्यमकर्तुम् ॥

(आक्षेपभाष्यम्)

कथम्—अकणिषम्, अरणिषम्, कणिता श्वः, रणिता श्व इति ?

(उद्योतः) भाष्ये-अकणिषमिति । सिजन्तस्याङ्गस्य मिपोऽमि लघूपधगुणः प्राप्नोति ॥ श्वःप्रयोगो लुडर्थः । तत्र डि डिते टाऽऽदेशे टिलोपे च तासप्रत्ययान्तमङ्गं भवति । तृचि तु अनकृतत्वात्र गुणप्राप्तिरिति भावः ॥

(समाधानभाष्यम्)

"आर्धधातुकस्येड्वलादेः" इत्यत्र इडिति वर्तमाने पुनरिड्ग्रहणस्य प्रयोजनम्—इडेव यथा स्यात्, यदन्यत्प्राप्नोति तन्मा भूदिति ॥

किं चान्यत्प्राप्नोति ?

गुणः ॥

(प्रदीपः) इडिति वर्तमान इति । 'नेड्वशि कृति' इत्यतः ॥

(उद्द्योतः) भाष्ये-पुनरिड्ग्रहणस्येति ॥ न च नेत्यस्य निवृत्त्यर्थं तत्; स्पष्टं चेदं नेड्वशीत्यत्र भाष्ये इति वाच्यम् । क्वचिदेकदेशोऽप्यनुवर्तेत इति न्यायेन नेड्वशीत्यत्रत्यनञ्। निवृत्तिसिद्धेरिति भावः ॥ वस्तुतस्त्वत्रत्यमिदं भाष्यमेकदेश्युक्तिः । आर्धधातुकस्येति सूत्रस्थेड्ग्रहणस्य च नेड्वशीति सूत्रे भाष्ये प्रत्याख्यानात् । तत्करणेन नियमरूपगुरुतरयत्नमाश्रित्यैतत्प्रत्याख्यानस्यायुक्तत्वात् ॥ अङ्गस्येत्यनुवृत्तावपि अङ्गाधिकारविहितविकारस्यैव व्यावृत्तेः शब्दमर्यादयाऽलाभाच्च । अन्त्येऽपि सिद्धत्ववचनस्य ज्ञापकत्वाश्रयणे गौरवमिति बोध्यम् ॥

(आक्षेपभाष्यम्)

यदि नियमः क्रियते, 'पिपठिषतेरप्रत्ययः पिपठीः' दीर्घत्वं न प्राप्नोति ॥

(प्रदीपः) पिपठीरिति । पिपठिषतेः क्विप्, 'अतो लोपः' इत्यकारलोपः । षत्वस्यासिद्धत्वात् 'ससजुषो रुः' इति रुत्वम् । पूर्वत्रासिद्धे न स्थानिवदित्यल्लोपस्य रुत्वे स्थानिवद्भावाभावः ॥

(उद्द्योतः) क्विबिति । अप्रत्यय इत्यस्याश्रूयमाणः प्रत्यय इत्यर्थः । कृदन्तत्वात्प्रातिपदिकत्वे स्वादयः ॥

(समाधानभाष्यम्)

नैष दोषः । आङ्गं यत्कार्यं तन्नियम्यते । न चैतदाङ्गम् ॥

(प्रदीपः) आङ्गमिति । 'अङ्गस्य' इत्यनुवर्तनादङ्गाधिकारविहितं यद्रूपान्तरमिष्टस्तदेव निवार्यते-इडेव यथा स्यादिति नियमेनेत्यर्थः ॥ 'र्वोरुपधायाः' इति च दीर्घत्वं नाङ्गम् । यत्तु 'ग्रहोऽलिटि दीर्घः' इति दीर्घत्वं, तद्वचनाद्भवति ॥ पिपठिषि ब्राह्मणकुलानीत्यत्र त्वकारलोपस्य स्थानिवद्भावान् झलन्तत्वाभावान्नुमभावः, तेन पिपठींषीति कथं 'सान्तमहतः संयोगस्य' इति दीर्घत्वमिति न चोदनीयम् । क्वौ विधिं प्रति न स्थानिवदित्यर्थो व्यवस्थापयिष्यते, न तु क्वौ लुप्तं न स्थानिवदिति ॥

(उद्द्योतः) झलन्तत्वाभावादिति । स्वविधौ स्थानिवत्त्वाभावादजन्तलक्षणोऽपि नेति द्रष्टव्यम् ॥ ननु क्वौ लुप्तस्य स्थानिवत्त्वनिषेधादल्लोपस्य स्थानिवत्त्वं दुर्लभमत आह—क्वाविति ॥

(समाधानान्तरभाष्यम्)

अथवा-असिद्धं दीर्घत्वं तस्यासिद्धत्वान्नियमो न भवति ॥ दीधीवेवीटाम् ॥ ६ ॥

(प्रदीपः) अथवेति । इडेवेत्यस्मिन्नियमे दीर्घत्वस्यासिद्धत्वान्नास्ति नियमेन व्यावृत्तिः । ततश्च शास्त्रदृष्ट्याऽविकृतरूप एवेदं, प्रयोग एव तु विकृतः । अलावीदित्यत्र तु सिज्लोप एकादेशे सिद्ध इत्यसिद्धत्वनिषेधवचनात्सवर्णदीर्घत्वं भवति ॥

(उद्द्योतः) अलावीदित्यत्रेति । न च समार्येत्यत्र ह्रस्वादङ्गादिति सिज्लोपाय सिद्धत्ववचनं चरितार्थं, सिद्धत्वे हि परत्वात्सिज्लोपे ततो वृद्धिः । अन्यथा पूर्वं वृद्धौ स न स्यादिति वाच्यम् । कावस्थायामस्तीति पदो सर्वतो वृद्धेरन्तरङ्गत्वेन तत्पक्षे सिज्लोपाप्राप्त्या तदेकवाक्यत्वेन पक्षान्तरेऽपि सिज्लोपाभावस्यैवौचित्येन समार्येत्येव रूपस्यौचित्यात्सत्यभिधाने ॥ सिज्लोप एकादेशे इति तु सिज्लोपोत्तरप्राप्तसवर्णदीर्घरूपैकादेशविषयमेवेति बोध्यम् । वस्तुतो नियमस्यैकदेश्युक्तित्वादिफलोऽयं विचार इति तत्त्वम् ॥ ६ ॥

(६ संयोगसंज्ञासूत्रम् ॥ १ । १ (४ आ. ४ ॥)

हलोऽनन्तराः संयोगः ॥ १ । १ । ७ ॥

(अनन्तरपदार्थनिरूपणाधिकरणम्)

(आक्षेपभाष्यम्)

अनन्तरा इति कथमिदं विज्ञायते—अविद्यमानमन्तरमेषामिति, आहोस्विदविद्यमाना अन्तरा एषामिति ?

(प्रदीपः) हलोऽनन्त० ॥ ७ ॥ कथमिति । किमन्तरशब्दस्य नञा बहुव्रीहिः, अथवा—अन्तराशब्दस्येति प्रश्नः । अन्तरं-विवरं, वर्णशून्यकालः ॥ अविद्यमाना इति । मध्ये येषामन्ये वर्णा अविद्यमाना इत्याधेयस्य निषेधः, न त्वाधारस्य ॥

(उद्द्योतः) हलोऽनन्तराः ॥ ७ ॥ अन्तराशब्दो मध्ये इत्यर्थे ॥ न त्वाधारस्येति । कालमात्रस्येत्यर्थः ॥

(प्रत्याक्षेपभाष्यम्)

किं चातः ?

(प्रत्याक्षेपसमाधानभाष्यम्)

यदि विज्ञायते-अविद्यमानमन्तरमेषामिति, अवग्रहे संयोगसंज्ञा न प्राप्नोति—'अप्स्विति-अप्ऽसु' (ऋ०सं०पद० १।२३।१९) इति । विद्यते ह्यत्रान्तरम् ॥

अथ विज्ञायते—अविद्यमाना अन्तरा एषामिति, न दोषो भवति ॥

(प्रदीपः) अवग्रह इति । अर्धमात्राकालोऽवग्रह इष्यते । अर्धमात्राकालं स्थित्वा वर्णान्तरं समुच्चार्यते तत्र 'गुरोरनृतः' इति प्लुतो न भवेत् ॥

(उद्द्योतः) अर्धेति । वर्णाद्वर्णोच्चारणेऽर्धमात्राकालस्य नियतत्वात्तदधिकोऽर्धमात्राकाल इत्यर्थः । अत एव मात्राकालोऽवग्रह इति प्रातिशाख्यान्तरैरविरोधः ॥

(द्वितीयपक्षाभ्युपगमभाष्यम्)

यथा न दोषस्तथाऽस्तु ॥

(प्रथमपक्षाभ्युपगमभाष्यम्)

अथवा पुनरस्तु-अविद्यमानमन्तरमेषामिति ॥

(आक्षेपस्मारणभाष्यम्)

ननु चोक्तम्-अवग्रहे संयोगसंज्ञा न प्राप्नोति—अप्स्विति अप्ऽसु-इति । विद्यते ह्यत्रान्तरम् ।

(आक्षेपबाधकभाष्यम्)

नैव दोषो न प्रयोजनम् ॥

(प्रदीपः) नैव दोष इति । दोषनिवृत्तये संज्ञा क्रियते, प्रयोजनाभिनिर्वृत्तये वा । इह चोभयाभावः, अधिकरणवृत्तेर्दूराद्धूतसंबन्धाभावात् । 'विचार्यमाणानां' इत्यादौ तु 'वाक्यस्य टेः' इत्यनुवर्तते, न तु 'गुरोरनृतः' इति अप्सव्यशब्दे दोष इति चेत्, नैवंविधे विषये प्रकृत्यवयवस्यावग्रहं पदकाराः कुर्वन्ति । अप्सुयोनिरित्यादावपि 'समासपदानामन्तोऽवगृह्यते' इति सुशब्दात्पूर्वस्य नास्त्यवग्रहः ॥

(उद्द्योतः) नैव दोष इत्यादेः-संज्ञाऽभावे न दोषः, संज्ञायां च न प्रयोजनमित्यर्थः-इत्याह—दोषनिवृत्तये इत्यादि ॥ अप्सव्यशब्दे इति । अप्सुशब्दाद्दिगादियति अपो योनियन्मतुप्स्वित्यलुक् ॥ प्रकृत्यवयवस्य=ताद्धतप्रकृत्यवयवस्य । अत्र च वैदिकसंप्रदाय एव शरणम् ॥ अन्त इति । समासे समस्यमानपदान्त एवावग्रहः । अयमपि वैदिकसंप्रदाय एव ॥

(इत्यनन्तरपदार्थनिरूपणम्)

(अथ प्रत्येकं संयोगसंज्ञानिराकरणाधिकरणम्)

(१३२ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ संयोगसंज्ञायां सहवचनं यथाऽन्यत्र ॥ * ॥

(भाष्यम्)

संयोगसंज्ञायां सहग्रहणं कर्तव्यम् । "हलोऽनन्तराः संयोगः सह" इति वक्तव्यम् ।

किं प्रयोजनम् ?

सहभूतानां संयोगसंज्ञा यथा स्यादेकैकस्य मा भूदिति ॥ 'यथाऽन्यत्र' । तद्यथा—अन्यत्रापि यत्रेच्छति सहभूतानां कार्यं, करोति तत्र सहग्रहणम् । तद्यथा-"सह सुपा" "उभे अभ्यस्तं सह" इति ॥

(प्रदीपः) संयोगसंज्ञायामिति । वृद्धिसंज्ञावत् आनन्तर्यव्यवस्थितानां हलां प्रत्येकं संयोगसंज्ञा प्राप्नोति ॥

(उद्द्योतः) नन्वनन्तरग्रहणादेकैकस्य संज्ञा दुर्लभेत्यत आह—आनन्तर्येति । एवं च तदुपलक्षणमिति भावः ॥

(दूषणप्रश्नभाष्यम्)

किं च स्यात् यद्येकैकस्य हलः संयोगसंज्ञा स्यात्?

(प्रदीपः) किं च स्यादिति । द्वयोरानन्तर्ये एकैकस्यापि संयोगसंज्ञायां गुरुसंज्ञाप्रतिबन्धकार्यसिद्धिरिति प्रश्नः ॥

(उद्द्योतः) संज्ञाप्रतिबन्धेति पाठे कर्मणि घञ् बोध्यः । संज्ञाप्रतिबद्धेति पाठः सुगम एव ॥

(दोषप्रदर्शनभाष्यम्)

इह-निर्यायात्, निर्वायात्-"वाऽन्यस्य संयोगादेः" इत्येत्वं प्रसज्येत ।

इह-संह्वषीष्टेति "ऋतश्च संयोगादेः" इतीट् प्रसज्येत ।

इह च—संह्रियत इति "गुणोऽर्तिसंयोगाद्योः" इति गुणः प्रसज्येत ॥

इह च—दृषत्करोति, समित्करोतीति संयोगान्तस्य लोपः प्रसज्येत ॥

इह च—शक्ता, वस्तेति "स्कोः संयोगाद्योः–" इति लोपः प्रसज्येत ॥

इह च—निर्यातो निर्वातः–"संयोगादेरातो धातोर्यण्वतः" इति निष्ठानत्वं प्रसज्येत ॥

(प्रदीपः) निर्यायादिति । सति रेफे यकारः संयोग इति एत्वप्राप्तिः ॥ ननु समुदायस्यापि संज्ञित्वे 'अचो रहाभ्यां द्वे' इति यकारस्य द्विर्वचने कृते कस्मादेत्वं न भवति । यथा-ग्लेयादिति । एत्वे कर्तव्ये 'पूर्वत्रासिद्धं' इति द्विर्वचनस्यासिद्धत्वान्नायं दोषः ॥

शक्तेति । तकारे झलि परतः ककारः संयोगो भवति, आदिश्च-इति लोपप्रसङ्गः ॥

(उद्द्योतः) कस्मादिति । बहूनां संनिधानेऽविशेषेण द्वयोर्बहूनां च संज्ञायाः सिद्धान्तयिष्यमाणत्वादिति भावः ॥ परिहरति—एत्वे इति । पूर्वत्रासिद्धीयमद्विर्वचन इति तु द्विर्वचने कार्येऽन्यस्यासिद्धत्वं नेत्यर्थकम्, न तु द्विर्वचनस्य तदभावप्रतिपादकमिति भावः ।

संयोगो भवत्यादिश्चेति । प्रत्येकसंज्ञापक्षे स्कोः संयोगावयवत्वासंभवेन षष्ठीसमासासंभवाल्लाघवाच्च कर्मधारय एवेति भावः ॥ आदिशब्दश्च पूर्वभूतसमीपवाची । आदित्वं च प्रत्यासत्त्या संयोगत्वाक्रान्तवर्णान्तरापेक्षयैवेति पदान्तांशे संयोगादिग्रहणचारितार्थ्यं बोध्यम् । अन्यथा तर्कयतेरप्रत्ययेऽर्क्–इत्यादावन्तकस्यापि लोपः स्यात् ॥

(दोषपरिहारभाष्यम्)

नैष दोषः।

यत्तावदुच्यते—इह तावन्निर्यायात्-निर्वायात्-"वाऽन्यस्य संयोगादेः" इत्येत्वं प्रसज्येतेति ॥

नैवं विज्ञायते—संयोग आदिर्यस्य सोऽयं संयोगादिः, संयोगादेरिति।

कथं तर्हि ?

संयोगावादी यस्य सोऽयं संयोगादिः, संयोगादेरिति। एवं तावत्सर्वमाङ्गं परिहृतम् ॥

(प्रदीपः) संयोगाविति। कथं वृत्तावुपसर्जनार्थस्य द्वित्वावगतिरिति चेत्। आदिग्रहणसामर्थ्यात्। अन्यथा 'संयोगात्' इति वक्तव्यं स्यात्, संयोगात्परो य आकारस्तदन्तस्याङ्गस्यैत्वमित्यर्थलाभात् ॥

(उद्द्योतः) कथं वृत्ताविति। अयं पूर्वपक्षोऽयुक्तः, संयोगस्य द्वित्ववत्त्वेन प्रतीतेरेव भावात्। संयोगत्वेनैवानेकसंयोगप्रतीतेः। न हि वृत्तावनेकबोध उपसर्जनाभेति भाष्यसंमतः। संख्याविशेषानवगमस्यैव भाष्यकृतोक्तत्वात्। न त्वनेकानवगम एति तेनोक्तमिति विभाव्यताम् ॥ संयोगात्पर इति। न चाङ्गावयवसंयोगग्रहणायादिग्रहणम्। तत्र यद्यपि दरिद्रातौ न फलम्। आर्धधातुकविवक्षायां तस्यालोपविधानात्, तथापि खट्वादिभ्य आचारक्विबन्तेभ्यो लिङि 'खट्वायात्' इत्यादौ एत्ववारणं फलमिति वाच्यम्। स्यसिच्सीयुट्तासिषु उपदेशपदानुवृत्त्या घुमास्थादिन्यस्यौपदेशिकस्यैव ग्रहणेन नामधातुष्वेत्वाप्रवृत्तेरिति भावः। खट्वादिभ्य आतो धातोरितिसूत्रस्थभाष्यप्रामाण्येनाचारक्विपोऽभावाच्च। सिद्धान्ते तु निर्यायादित्यादिवारणायाङ्गावयवसंयोगग्रहणाय तदिति बोध्यम्।

(द्वितीयदूषणोद्धारभाष्यम्)

यदप्युच्यते—इह दृषत्करोति-समित्करोति-इति संयोगान्तस्य लोपः प्रसज्येतेति।

नैवं विज्ञायते—संयोगोऽन्तो यस्य तदिदं संयोगान्तं, संयोगान्तस्येति।

कथं तर्हि ?

संयोगावन्तावस्य तदिदं संयोगान्तं, संयोगान्तस्येति ॥

(प्रदीपः) संयोगावन्ताविति। अत्रापि संयोगस्य लोप इत्येव, संयोगेन पदस्य विशेषणात्तदन्तविधौ सिद्धेऽन्तग्रहणमाश्रितसंख्याभेदः संयोगो यथा गृह्येतेत्येवमर्थं विज्ञायते ॥

(तृतीयदूषणोद्धारभाष्यम्)

यदप्युच्यते—इह च शक्ता-वस्तेति "स्कोः संयोगाद्योरन्ते च" इति लोपः प्रसज्येतेति।

नैवं विज्ञायते—संयोगस्यादी-संयोगादी, संयोगाद्योरिति।

कथं तर्हि ?

संयोगयोरादी-संयोगादी, संयोगाद्योरिति ॥

(प्रदीपः) संयोगयोरिति। षष्ठीसमास आश्रीयत इत्यर्थः। 'संयोगयोः' इति तु द्विवचननिर्देशः स्कोर्द्वित्वात्तत्समीपयोरपि हलोर्द्वित्वात्। तेनायमर्थः—झलि परतो यः संयोगः पदान्ते च यः संयोगः, तस्यादिः-समीपो यः ककारः सकारश्च तयोर्लोप इति। न चैवं सति 'शक्ता-वस्ता' इत्यत्र लोपः प्राप्नोति ॥

(उद्द्योतः) भाष्ये—आदी इति। यद्यपि मुख्यादित्वमुभयोर्न्यायतं, तथाप्येक आदिशब्दो गौण इति भावः॥ पूर्ववद्द्विवचनान्तसमासेन दोषपरिहार इति न भाष्यार्थः, उभयत्रापि द्विवचनोपादानात्। अत आह—षष्ठीति। एवं च झलंशेऽपि संयोगादिविशेषणमर्थवद्भवतीति भावः॥ आदिशब्दश्च नावयववाची, असंभवादित्याह—समीप इति। झलादिविशेष्यस्य संयोगस्योपसर्जनत्वेऽपि सौत्रत्वात्तुचिः। न च शक्तेत्यत्र व्यपदेशिवद्भावेन स्वस्यापि स्वसमीपत्वेन दोषस्तदवस्थः, आदिग्रहणसामर्थ्याद् व्यपदेशिवद्भावाप्रवृत्तेः ॥

(चतुर्थदूषणोद्धारभाष्यम्)

यदप्युच्यते—इह च निर्यातो निर्वात इति "संयोगादेरातो धातोर्यण्वतः" इति निष्ठानत्वं प्रसज्येतेति।

नैवं विज्ञायते—संयोग आदिर्यस्यासौ संयोगादिः, संयोगादेरिति।

कथं तर्हि ?

संयोगावादी यस्य सोऽयं संयोगादिः, संयोगादेरिति।

(प्रदीपः) 'संयोगादेरातः' इत्यत्रापि 'संयोगादातः' इत्येव संयोगात्परो य आकारस्तदन्ताद्धातोर्नत्वमिति सिद्धे आदिग्रहणं द्वित्वसंख्याश्रयणार्थम् ॥

(आक्षेपभाष्यम्)

कथं कृत्वा एकैकस्य संयोगसंज्ञा प्राप्नोति ?

(प्रदीपः) कथं कृत्वेति। संयोगसंज्ञाया अन्वर्थत्वात्—संयुज्यन्तेऽस्मिन्वर्णा इति समुदायः संयोग इत्यर्थस्याश्रयणात्सहग्रहणं न कर्तव्यमित्यर्थः ॥

(उद्द्योतः) वस्तुतस्तु प्रत्येकं संज्ञेति पक्षो भाष्यकृता स्वात्र लभ्यत एवेति व्युत्पादयितुं गूढाशयः पृच्छति—भाष्ये—कथं कृत्वेति ॥ तमेवालाभं व्याचष्टे—संयोगेति। एवंचान्वर्थसंज्ञाविरोधात्प्रत्येकं वाक्यपरिसमाप्तिन्यायो नात्राश्रयितुं शक्यत इति व्यर्थं सहेतीति भावः॥ किं च श्रुतमानन्तर्यं प्रत्येकसंज्ञावादिनोपलक्षणमाश्रयितव्यम्। विशेषणत्वमेवोचितं, तत्त्वे संभवति उपलक्षणत्वस्यान्याय्यत्वात्। किं चाद्यन्तग्रहणसामर्थ्याद्द्विवचनान्तेनैव विग्रह इत्यर्थस्य नियमेनालाभः। बहुवचनान्तेनापि संभवादित्याहुः ॥ वस्तुतोऽन्वर्थसंज्ञा चिन्त्या, तदाश्रयणे घटपटौ संयुज्येते यत्रेत्यादौ संयोगानुयोगिप्रतियोग्यतिरिक्तस्यैवान्यपदार्थतया प्रतीतेर्व्युत्पन्नत्वेन तद्व्यतिरिक्तघटितपदवाक्यरूपसमुदायस्य संज्ञापत्त्यानिष्टापत्तेः।

तस्मान्महासंज्ञाकरणं प्राचामनुरोधेनेत्येव ज्यायः ॥ अत एव भगवता गर्गदण्डनन्यायमाश्रित्य सहग्रहणं प्रत्याख्यातं, न तु महासंज्ञयेत्यलम् ॥

(समाधानभाष्यम्)

प्रत्येकं वाक्यपरिसमाप्तिर्दृष्टा-इति । तद्यथा वृद्धिगुणसंज्ञे प्रत्येकं भवतः ॥

(समाधानबाधकप्रतिबन्दीसिद्धान्तिभाष्यम्)

ननु चायमप्यस्ति दृष्टान्तः—समुदाये वाक्यपरिसमाप्तिः-इति । तद्यथा—गर्गाः शतं दण्ड्यन्ताम्-इति । अर्थिनश्च राजानो हिरण्येन भवन्ति, न च प्रत्येकं दण्डयन्ति ॥

(सहग्रहणप्रत्याख्यानभाष्यम्)

सत्येतस्मिन्दृष्टान्ते यदि तत्र प्रत्येकमित्युच्यते, इहापि सहग्रहणं कर्तव्यम् । अथ तत्रान्तरेण प्रत्येकमितिवचनं प्रत्येकं वृद्धिगुणसंज्ञे भवतः, इहापि नार्थः सहग्रहणेन ॥

(आक्षेपभाष्यम्)

अथ यत्र बहूनामानन्तर्यं, किं तत्र द्वयोर्द्वयोः संयोगसंज्ञा भवति, आहोस्विदविशेषेण ?

कश्चात्र विशेषः?

(प्रदीपः) आहोस्विदिति । द्वयोरित्यस्य विशेषस्यानाश्रयणाद्बहूनामेवेत्यर्थः । यथा पपाचेत्यत्र समुदायस्यैकाचो द्विर्वचनं नावयवैकाचः । यदा तु द्वयोरेव हलोरानन्तर्यं तदा द्वयोर्भवत्येव, 'हलः' इति जातौ बहुवचननिर्देशात् ॥

(उद्योतः) ननु 'अविशेषेण' इत्यस्य द्वयोर्बहूनां चेति नार्थः । अस्याविशेषस्याग्रे वक्ष्यमाणत्वात्, मस्जौ दोषदानासङ्गतेश्चात आह—द्वयोरित्यस्येति । अत एव भाष्ये—समुदाये संयोगादिलोप इति वक्ष्यति ॥ तत्र युक्तिमाह—यथेति ॥ हल इति जाताविति । वस्तुतो हलौ च हलश्चेत्येकशेषः, स्वरितादिति सत्रेऽनुदात्तानामित्यत्र भाष्ये तथैव वक्ष्यमाणत्वात् ॥

(१३३ आक्षेपवार्तिकम् ॥ २ ॥)

॥ * ॥ समुदाये संयोगादिलोपो मस्जेः ॥ * ॥

(भाष्यम्)

समुदाये संयोगादिलोपो मस्जेर्न सिद्ध्यति । मङ्क्ता, मङ्क्तुम् ।

इह च निर्ग्लेयात्-निर्ग्लायात्, निर्म्लेयात्-निर्म्लायात्, "वाऽन्यस्य संयोगादेः" इत्येत्वं न प्राप्नोति ॥

इह च संस्वरिषीष्टेति "ऋतश्च संयोगादेः" इतीण्न प्राप्नोति ॥

इह च संस्वर्यते इति "गुणोऽर्तिसंयोगाद्योः" इति गुणो न प्राप्नोति ॥

इह च गोमान्करोति-यवमान्करोतीति "संयोगान्तस्य लोपः" इति लोपो न प्राप्नोति ॥

इह च निर्ग्लान इति "संयोगादेरातो धातोर्यण्वतः" इति निष्ठानत्वं न प्राप्नोति ॥

(प्रदीपः) मङ्क्तेति । 'मस्जिनशोर्झलि' इति नुमि कृते नसजानां संयोगसंज्ञा, न तु सजयोरिति सलोपाप्रसङ्गः ॥ निर्ग्लेयादिति । यः संयोगो नासावङ्गादिः, यश्चाङ्गादिर्गकारलकारसमुदायो नासौ संयोगः ॥

(उद्योतः) भाष्ये 'पूर्वं धातुरुपसर्गेण' इत्याश्रित्य क्वचित्, क्वचिच्च वाक्यसंस्कारपक्षाश्रयेण दोषोपन्यासः ॥

(प्रथमपक्षाभ्युपगमभाष्यम्)

अस्तु तर्हि-द्वयोर्द्वयोः संयोगः ॥

(१३४ आक्षेपवार्तिकम् ॥ ३ ॥)

॥ * ॥ हलोः संयोग इति चेत् द्विर्वचनम् ॥ * ॥

(भाष्यम्)

द्वयोर्हलोः संयोग इति चेत् द्विर्वचनं न सिद्ध्यति । इन्द्रमिच्छति-इन्द्रीयति, इन्द्रीयतेः सन्-इन्दिद्रीयिषति । "न न्द्राः संयोगादयः" इति द्विर्वचनं न प्राप्नोति ॥

(प्रदीपः) इन्दिद्रीयिषतीति । अत्र द्वौ संयोगौ-नदौ दरौ च, तत्र दकारस्य संयोगादित्वात् द्विर्वचननिषेधप्रसङ्गः ॥

(१३५ समाधानवार्तिकम् ॥ ४ ॥)

॥ * ॥ न वाऽज्विधेः ॥ * ॥

(भाष्यम्)

न वा एष दोषः ।

किं कारणम् ?

अज्विधेः । नदराः संयोगादयो न द्विरुच्यन्ते । अजादेरिति वर्तते ॥

(प्रदीपः) न वाऽज्विधेरिति । अजाश्रयः प्रतिषेधविधिः । 'अजादेः' इति कर्मधारयः । तेनाच आदेः परे-अनन्तरा न्द्रा न द्विरुच्यन्ते । इन्द्रशब्दे तु दकारो नकारेण व्यवहितत्वात् द्विरुच्यत एव ॥

(उद्योतः) परेऽनन्तरा इति । तस्मादित्युत्तरस्येत्यस्योपस्थितेरिति भावः । चन्द्रीयतेः सनोऽभिधाने यथेष्टं नामधातुष्विति द्वितीयैकाचो द्वित्वं नकारसहितस्यैव । आद्यवयवाचः परत्वाभावेनैतन्निषेधाप्रवृत्तेरिति बोध्यम् ॥

(आक्षेपभाष्यम्)

अथ यद्येव बहूनां संयोगसंज्ञा, अथापि द्वयोर्द्वयोः । किं गतमेतदियता सूत्रेण, आहोस्विदन्यतरस्मिन्पक्षे भूयः सूत्रं कर्तव्यम् ?

(समाधानभाष्यम्)

गतमित्याह ।

कथम् ?

यदा तावद्बहूनां संयोगसंज्ञा, तदेवं विग्रहः करिष्यते-अविद्यमानमन्तरमेषाम्-इति ॥

(प्रदीपः) अविद्यमानमिति । बहूनां चानन्तरत्वे समुदायद्विर्वचनवत् बहूनामेव संयोगसंज्ञा, न द्वयोर्द्वयोः ॥

(उद्योतः) बहूनां चाविवरत्वे इति । 'बहूनां चानन्तरत्वे' इति क्वचित्पाठः । नन्वत्र विग्रहे कमित्यादौ कमयोः संयोगसंज्ञा स्यात्, तयोर्मध्ये वर्णशून्यकालरूपच्छिद्राभावादिति चेन्न । वर्णशून्यकालव्यवायमात्रवारणे फलाभावात्सामर्थ्येन सवर्णकालव्यवायोऽपि व्यावर्त्यत इत्यदोषः ॥ द्विर्वचनवदिति । 'एषां' इति बहुवचनादिति न भ्रमितव्यम्, तस्य सूत्रे हल इतिवत्त्वस्वात् । अन्तराशब्देन विग्रहेऽपि तत्सत्त्वाच्च । अन्यथा द्वयोर्न स्यात् । किं त्वन्तरशब्देन विग्रहाद्बहूनां समवधाने तेषामप्यनन्तरत्वादिति भावः ॥

(समाधानशेषभाष्यम्)

यदा द्वयोर्द्वयोः, तदैवं विग्रहः करिष्यते—अविद्यमाना अन्तरा एषाम्—इति । द्वयोश्चैवान्तरा कश्चिद्ध्रियते वा न वा ॥

(प्रदीपः) अविद्यमान इति । मध्ये य आधेयः स द्वयोरेव मध्ये भवतीति संसर्गवद्विप्रयोगस्यापि विशेषावगतिहेतुत्वाद्बहुषु द्वयोर्द्वयोः संयोगसंज्ञा भवतीति पक्षः ॥ द्वयोश्चैवान्तरेति । 'अन्तरान्तरेण युक्ते' इति द्वितीया कस्मादत्र न भवति । उच्यते—यदा मध्यापेक्षया नियतावधिरूपता विवक्षिता—'त्वां च मां चान्तरा कमण्डलुः' 'अग्नी अन्तरा' 'धवखदिरावन्तरा' इति, तदा द्वितीया ॥ यदा तु नियतावधित्वं न विवक्ष्यते, अपि तु संबन्धमात्रं तदा षष्ठ्येव भवति । तदा हि न ज्ञायते—किं तयोरेवावधित्वमुतान्यसहितयोः—इत्यवधिनियमाभावात् । द्वितीयाया युक्तग्रहणान्नियतावधिविवक्षाविषयाया अभावः ॥

(उद्योतः) संसर्गविप्रयोगावेव भाष्ये दर्शयति—द्वयोश्चेति । ध्रियत इत्यन्तं दृष्टान्तार्थम् । अवरसाधेनुरित्यादौ विप्रयोगोऽपि विशेषावगतिहेतुर्दृष्टः । अन्तरा ध्रियत इति—न ध्रियत इति वा यत्तत् द्वयोरेवेत्यर्थः ॥ नियतावधिरूपतेति । अवधित्वं हि अन्यासहितत्वे एव तयोर्नियमेन भवति, अन्यसाहित्ये तु न तत्रावधित्वस्य नियमेन प्रतीतिः, अवधित्वविवक्षायामेव च द्वितीयेति भावः ॥ यस्य च नियमेनावधित्वं तस्यैवावधित्वविवक्षा शब्देनेति तात्पर्यम् । नियतत्वं—अन्यासहितत्वं, तद्वैशिष्ट्येन याऽवधिरूपता सा विवक्षिता यदा भवतीत्यक्षरार्थः । अन्यथा—अवधित्वविवक्षायां द्वितीया, तस्त्वाविवक्षायां षष्ठीत्यर्थस्यैव शब्दतो लाभेन नियतेति कथनमधिकं स्यादिति बोध्यम् ॥ युक्तग्रहणादिति । न च तदभावेऽन्तराऽन्तरेणशब्दाभ्यां द्वितीयापत्तिः । तयोरव्ययत्वेन विशेषाभावात् । न च प्रथमाबाधनेन सपूर्वायाः प्रथमाया इत्यस्याप्रवृत्त्यर्थम् । व्यवस्थितविभाषया तस्य सुपरिहरत्वात् । तस्माद्युक्तग्रहणं संबन्धविशेषस्य प्रतिपादनाय, अवधित्वस्य प्रतियोगित्वस्य वा । तेन प्रयोगमन्तरेणेत्यपि सिद्धम् । एवं च संबन्धमात्रविवक्षायां षष्ठ्येवेति भावः ॥

(आक्षेपभाष्यम्)

एवमपि बहूनामेव प्राप्नोति । यान् हि भवानत्र षष्ठ्या प्रतिनिर्दिशति, एतेषामन्येन व्यवाये न भवितव्यम् ॥

(प्रदीपः) यान् हीति । 'एषां' इति बहुवचननिर्देशादिति न बोद्धव्यम्, बहुत्वस्याविवक्षणात् । अन्यथा 'शिक्षा' इत्यादौ द्वयोर्न स्यात् । तस्माद्योऽसावन्तरा स द्वयोर्भवति न वेति यदुक्तं तत्रोच्यते—यदा द्वयोर्द्वयोरन्तरा न भवति तदा बहवोऽनन्तरा इति तेषामेव प्राप्नोति । यदा हि बहूनां मध्ये भिन्नजातीयोऽच् भवति, तदा मा भूत् । तदभावे तु प्रवर्तितव्यमेव बहूनां संज्ञया, समुदायद्विर्वचनवदित्यर्थः ॥

(उद्योतः) ननु भाष्ये द्वयोरिति षष्ठीद्विवचननिर्दिष्टस्य द्वित्वात् 'यान्हि' इति बहुवचननिर्देशोऽनुपपन्न इति चेन्न । प्रकृते द्वयोरित्यनेन न केवलौ वर्णौ निर्दिष्टौ । तथा सति तयोरेवावधित्वात् द्वितीयापत्तिः, किं त्वन्यसहितावपि, अत एव षष्ठी । एवं च त्रयाणां समवधाने द्वयोः समुदाययोरवधित्वविवक्षणेन द्वयोः समुदाययोरनन्तरत्वे तत्समुदायवर्तिहलां बहुत्वात्तदुपपत्तिः । 'अनन्तरा' इत्यनेन च न विद्यतेऽन्तरा यौ वर्णौ तौ, यौ च समुदायावन्तरा न विद्यते तौ च गृह्येते, एकशेषादिति न दोषः । तत्सर्वमभिप्रेत्याह—यदा द्वयोर्द्वयोरिति । अवयवकसमुदाययोरित्यर्थः । यान् वर्णान् द्वयोः समुदाययोरित्यर्थकषष्ठ्या प्रतिनिर्दिशतीति भाष्यार्थ इति भावः ॥ अनन्तरा इत्यस्यात्र पक्षे व्यावर्त्यं दर्शयन् पूर्वोक्तमेवार्थं दृष्टान्तेनोपपादयितुमाह—यदा हि बहूनामिति । न च स्तेत्यादौ रेफषकारयोर्वर्णयोरन्तरा कस्यचित्सत्त्वेऽपि सरौ रषौ चेति समुदायौ तयोश्चान्तरा न कश्चिदिति तेषां संयोगत्वं स्यादिति वाच्यम् । वर्णयोरन्तरा विद्यमानत्वेनानन्तरत्वाभावात् । सर्वविधानन्तरत्वस्यैव निमित्तत्वादित्याहुः ।

(समुदायसंज्ञाभ्युपगमभाष्यम्)

अस्तु तर्हि समुदाये संज्ञा ॥

(समुदायसंज्ञादूषणस्मारणभाष्यम्)

ननु चोक्तं—*समुदाये संयोगादिलोपो मस्जेः* इति ॥

(समुदायसंज्ञादूषणनिराकरणसिद्धान्तिभाष्यम्)

नैष दोषः । वक्ष्यत्येतत्—*अन्त्यात्पूर्वो मस्जेर्मिदनुषङ्गसंयोगादिलोपार्थम्* इति ।

(प्रदीपः) अन्त्यात्पूर्व इति । तच्चानुषङ्गलोपार्थमवश्यं वक्तव्यम् । अन्त्यादचः परे नुमि सत्यनुपधात्वात् 'ममः' इत्यत्र नलोपो न स्यात् । कृतेऽपि संयोगादिलोपे तस्यासिद्धत्वादनुपधात्वमेव नकारस्य ॥

(उद्योतः) अनुषङ्गः—नकारः । तल्लोपोऽनिदितामित्यनेन ॥

(समुदायसंज्ञादूषणनिराकरणैकदेशिभाष्यम्)

अथवाऽविशेषेण संयोगसंज्ञा विज्ञास्यते—द्वयोरपि, बहूनामपि । तत्र द्वयोर्या संयोगसंज्ञा तदाश्रयो लोपो भविष्यति ॥

(प्रदीपः) अविशेषेणेति । बहुष्वनन्तरेषु द्वयोर्द्वयोरपि भवति बहूनामपि—इत्ययमिदानीमविशेषः । कार्यार्थत्वात्संयोगसंज्ञाया विरोधाभावादेकया संज्ञया सर्वेषामनुग्रहात्सिद्धा द्विर्वच-

नेन वैधर्म्यादविशेषेणेत्युक्तम् ॥

(उद्द्योतः) बहूनामपीति । न्यायतः सूत्रात्सम्भवमात्रेणेदमुक्तम् । न तु फलोदाहरणमस्य न्याय्यमस्ति । ध्वनितं चेदमङ्गेन संयोगादिमिति ग्रन्थेन भाष्ये ॥ ननु द्विर्वचनन्यायेन समुदायस्यैव संज्ञा स्यादिति कथमेतत्पक्षोत्थानमत आह—कार्येति । द्विर्वचनं हि श्रवणार्थमेव न शास्त्रीयकार्यार्थम् । एकस्याचो बह्ववयवत्वं युगपद्विरुद्धं च । एकेन द्वित्वेन सर्वानुग्रहश्चेति वैषम्यम् ॥

(समुदायसंज्ञापक्षोक्तदूषणान्तरनिराकरणसिद्धान्तिभा०)

यदप्युच्यते—'इह च निर्ग्लायात्-निर्म्लायात्-निर्ग्लेयात्-निर्म्लेयात् "वाऽन्यस्य संयोगादेः" इत्येत्वं न प्राप्नोतीति ।

अङ्गेन संयोगादिं विशेषयिष्यामः—अङ्गस्य संयोगादेरिति । एवं तावत्सर्वमाङ्गं परिहृतम् ॥

यदप्युच्यते—इह च गोमान्करोति-यवमान्करोतीति "संयोगान्तस्य लोपः" इति लोपो न प्राप्नोतीति ।

पदेन संयोगान्तं विशेषयिष्यामः—पदस्य संयोगान्तस्येति ॥

यदप्युच्यते—इह निर्ग्लानो निर्म्लानः "संयोगादेरातो धातोर्यण्वतः" इति निष्ठानत्वं न प्राप्नोतीति ॥

धातुना संयोगादिं विशेषयिष्यामः—धातोः संयोगादेरिति ॥

(प्रदीपः) बहूनां संनिधौ बहूनामेव संयोगसंज्ञेत्यस्मिन्पक्षे आश्रीयमाणे मस्जेर्दोषः 'अन्त्यात्पूर्वः-' इति परिहृतः । शेषान्दोषान्परिहर्तुमाह—यदप्युच्यत इति । पाठक्रमादर्थक्रमो बलीयानिति 'मस्जेरन्त्यात्पूर्वं' इत्यस्यानन्तरमिदं द्रष्टव्यम् ॥ निर्ग्लेयादित्यादिषु यद्यपि त्रयो हलः सन्निहितास्तथापि कार्यार्थत्वात्संज्ञायास्त्रिषु च कार्याभावादङ्गपदधात्ववयवसंयोगस्य तेषु लक्षणेष्वाश्रितत्वात्समुदाये कार्याभावे चावयवानां स्वकार्यारम्भात् द्वयोरेव संज्ञा प्रवर्तत इति भाष्यार्थः ॥ व्याख्यानान्तरमत्र क्लिष्टत्वान्नोक्तम् ॥

(उद्द्योतः) ननु पक्षान्तरेण व्यवधानादासत्त्यभाव इत्यत आह—पाठेति । शब्दस्यार्थप्रत्यायनाङ्गत्वेन गुणत्वात्तदीयः क्रम आर्थक्रमविरोधे दुर्बल इति भावः ॥ अङ्गपदधात्ववयवेति । संयोगादेरित्यादावाद्यन्तशब्दयोरवयववाचितयेति भावः ॥ अयमाशयः—अङ्गादेरादावन्ते वा व्यञ्जनत्रयाभावात् त्रयाणां फलाभावात्संज्ञाऽप्राप्तौ कथं द्वयोर्न स्यात्-इति ॥ यद्यपि सामानाधिकरण्यान्वयेऽपि अङ्गावयवस्यैव संयोगस्याश्रयणं, नान्यस्य-इति अङ्गेन संयोगादिं विशेषयिष्याम इत्यनुपपन्नं, तथापि संयोगरूपमादिमङ्गेन परिच्छेत्स्यामः-अङ्गावयवसंयोगस्यैव बहुव्रीहिणाऽऽश्रयणमित्यर्थ इति न दोषः । एवंच बहूनामपीत्याश्रयणे फलाभाव इति स्पष्टमेवोक्तम् । क्लिष्टकल्पनया तादृशसंयोगानयनं तु न, अनभिधानादित्याशयः ॥ अदादिषु 'षस स्वप्ने' इत्येव पाठो न तु 'षस सस्ति स्वप्ने' इति, एतद्भाष्यप्रामाण्याज्जक्षित्यादिसूत्रस्थभाष्यप्रामाण्याच्चेति बोध्यम् ॥ व्याख्यानान्तरमिति । पाठक्रमाबाधायैवं व्याचक्षते—'न प्राप्नोतीति' इत्यत्र-इतिशब्दो यस्मादर्थ उत्तरान्वयी, तस्मादङ्गेन संयोगादिर्विशेष्यते-अङ्गावयवः संयोगो गृह्यते-इत्यर्थः । एवं च बहूनामेव संयोगत्वे यः संयोगो नासावङ्गावयवः, यश्चाङ्गावयवो नासौ संयोगः । तस्मादेत्वं न प्राप्नोतीति यदपि, तदप्यसत् । यतोऽविशेषेण संज्ञोच्यते इति शेषः-इति । तत् क्लिष्टम्, शेषपूरणात् । इतेः स्वरसतो वाक्यसमाप्त्यर्थतायाः प्रतीयमानत्वाच्च । एवं तावत्सर्वमाङ्गं परिहृतमित्यस्यास्वारस्याच्च ॥

(इति समुदायसंज्ञापक्षस्थापनम्)

(अथानन्तरशब्दार्थनिरूपणम्)

(१३६ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ स्वरानन्तर्हितवचनम् ॥ * ॥

(भाष्यम्)

स्वरैरनन्तर्हिता हलः संयोगसंज्ञा भवन्तीति वक्तव्यम् ।

किं प्रयोजनम् ?

व्यवहितानां मा भूत् । पचति, पनसम् ॥

(प्रदीपः) पचति पनसमिति । 'हलः' इति वचनाद्चा सह सकारमकारयोर्मा भूत्संज्ञा । तयोरेव तु प्राप्नोति, ततश्च सलोपप्रसङ्गः ॥

(उद्द्योतः) हल इतीति । तद्धि असावित्यादौ स्कोरिति सलोपवारणायावश्यकमिति भावः ॥

(आक्षेपबाधकभाष्यम्)

ननु च 'अनन्तराः' इत्युच्यते । तेन व्यवहितानां न भविष्यति ॥

(आक्षेपसाधकं भाष्यवार्तिकम्)

दृष्टमानन्तर्यं व्यवहितेऽपि ॥

(भाष्यम्)

व्यवहितेऽप्यनन्तरशब्दो दृश्यते । तद्यथा—'अनन्तराविमौ ग्रामौ' इत्युच्यते, तयोश्चैवान्तरा नद्यश्च पर्वताश्च भवन्ति ॥

(आक्षेपबाधकभाष्यम्)

यदि तर्हि व्यवहितेऽप्यनन्तरशब्दो भवति, आनन्तर्यवचनमिदानीं किमर्थं स्यात् ?

(आक्षेपसाधकं भाष्यवार्तिकम्)

आनन्तर्यवचनं किमर्थमिति चेदेकप्रतिषेधार्थम् ॥

(भाष्यम्)

एकस्य हलः संयोगसंज्ञा मा भूदिति ॥

किं च स्यात् यद्येकस्य हलः संयोगसंज्ञा स्यात् ?

इयेष-उवोष "इजादेश्च गुरुमतोऽनृच्छः" इत्याम् प्रसज्येत ॥

(प्रदीपः) **एकप्रतिषेधार्थमिति** । 'अनन्तराः' इत्यनेन संज्ञाया विषयो निर्दिश्यते । यत्रानन्तरव्यवहारस्तत्र संज्ञा । न चैकस्मिन्ननन्तरव्यवहार इति भावः । एकप्रतिषेधस्य च प्रयोजनम्-इयेषेत्यादौ 'इजादेः-' इत्यामो निवृत्तिः । **गुरुमद्वचनमियायेत्यादिनिवृत्त्यर्थं स्यात्** ॥

(उद्द्योतः) न चेति । आनन्तर्यस्य सप्रतियोगिकत्वादिति भावः ॥ प्रकृते चान्यस्य प्रतियोगिनोऽनुपादानादुपस्थितहलेव प्रतियोगित्वेनाश्रीयत इति बोध्यम् ॥ भाष्ये—उवोषेति प्रसङ्गोद्धारितम् । तस्य विकल्पितामकत्वात् । उवोखेति कवर्गद्वितीयान्तो वा पाठः ॥ **इयायेति** । इण् स इत्यस्यामवस्थायां व्यपदेशिवद्भावादिजादित्वमस्ति, गुरुमत्त्वं तु न । न चेयङि कृते गुरुमदिजादित्वादाम् स्यादिति वाच्यम् । लिड्धातुसंनियोगेन संपन्नस्य गुरुमदिजादित्वस्य तद्विघातकत्वाभावादिति भावः ॥

(१३७ समाधानवार्तिकम् ॥ ६ ॥)

॥ * ॥ न वाऽतज्जातीयव्यवायात् ॥ * ॥

(भाष्यम्)

न वा एष दोषः ।

किं कारणम् ?

अतज्जातीयस्य व्यवायात् । अतज्जातीयकं हि लोके व्यवधायकं भवति ॥

(अनुयोगभाष्यम्)

कथं पुनर्ज्ञायते—अतज्जातीयकं लोके व्यवधायकं भवतीति ?

(उत्तरभाष्यम्)

एवं हि कंचित् कश्चित्पृच्छति—'अनन्तरे एते ब्राह्मणकुले' इति । स आह—नानन्तरे, वृषलकुलमनयोरन्तरा-इति ॥

(प्रदीपः) **वृषलकुलमिति** । यद्यपि ब्राह्मणकुलमपि तयोर्व्यवधायकं तथापि भिन्नजातीयमव्यवधायकमिति यदुक्तं तदनेन निवर्त्यते ॥

(उद्द्योतः) कुलमत्र गृहम् ॥ ब्राह्मणकुलमपीति । तद्रूपेण ग्रहणे तस्यापि विजातीयत्वादिति भावः ॥ भाष्ये—अनयोरन्तरा-इति षष्ठ्युपादानादन्यसंहितयोरवधित्वसूचनात्तद्रूपेणाग्रहणबोधनात् ब्राह्मणकुलस्याव्यवधायकत्वमेवेत्यन्ये ॥ भिन्नजातीयेति । तयोश्चान्तरा नद्यश्च पर्वताश्च भवन्तीति भाष्येणेत्यर्थः ॥

(आक्षेपभाष्यम्)

किं पुनः कारणं क्वचिदतज्जातीयं व्यवधायकं भवति, क्वचिन्न ?

(समाधानभाष्यम्)

सर्वत्रैव ह्यतज्जातीयकं व्यवधायकं भवति ॥

(आक्षेपभाष्यम्)

कथम्—अनन्तराविमौ ग्रामाविति ?

(समाधानभाष्यम्)

ग्रामशब्दोऽयं बह्वर्थः । अस्त्येव शालासमुदाये वर्तते, तद्यथा—ग्रामो दग्ध इति । अस्ति वाटपरिक्षेपे वर्तते, तद्यथा—ग्रामं प्रविष्ट इति । अस्ति मनुष्येषु वर्तते, तद्यथा—ग्रामो गतो ग्राम आगत इति । अस्ति सारण्यके ससीमके सस्थण्डिलके वर्तते, तद्यथा-ग्रामो लब्ध इति ॥

तद्यः सारण्यके ससीमके सस्थण्डिलके वर्तते तमभिसमीक्ष्यैतत्प्रयुज्यते—अनन्तराविमौ ग्रामाविति । सर्वत्रैव ह्यतज्जातीयकं व्यवधायकं भवति ॥ हलोऽनन्तराः ॥ ७ ॥

(प्रदीपः) **ग्रामशब्दोऽयमिति** । केचिदर्थभेदेन शब्दभेदमिच्छन्ति । प्रत्यभिज्ञानं तु सामान्यनिबन्धनम् ॥ अन्ये तु एकशब्दत्वं, तत्र चानेकशक्तियोगः-एकशक्तित्वं चेति दर्शनविकल्पः ॥ तत्र यदा एकशब्दत्वपक्षस्तदा **'तद्यः सारण्यके'** इति भाष्यं शक्तिभेदादुपचरितभेदाश्रयम् ॥ भेदपक्षे तु **'ग्रामशब्दोऽयं बह्वर्थः'** इति भाष्यम् । अभिन्नसामान्यनिमित्तैकत्वाध्यवसायाश्रयम् ॥ **तद्यः सारण्यक इति** । ततश्च ग्रामशब्दार्थे नदीनां पर्वतानां चान्तर्भावादव्यवधायकत्वाभावादानन्तर्यं ग्रामयोरुच्यते । **'ग्रामे नाध्येयं'** इत्यत्र तु ग्रामशब्दो वाटपरिक्षेपवृत्तिः, शुचौ देशेऽध्ययनप्रतिपादनतात्पर्यात् । ततः सीमन्यधीयत एव ॥ ७ ॥

(उद्द्योतः) ग्रामशब्दोऽयमित्यस्य तद्यः सारण्यक इत्यस्य चाविरोधायाह—केचिदिति । अन्यथाऽन्यथाऽनेकार्थत्वमिति तदाशयः । सामान्यं च ग्रामशब्दत्वादि ॥ अन्ये त्विति । व्यक्तिभेदकल्पनायां गौरवमिति तदाशयः ॥ तत्र यदेति । निरूपकभेदाच्छक्तिभेद इति भावः ॥ एकेति । समवायैकत्वनये रसो रूपवानित्यादिप्रयोगवदन्यार्थबोधकालेऽन्यार्थबोधो वारणीयः । तदर्थसंबन्धेन शक्यग्रहाद् तत्तदर्थविशिष्टशक्तिभेदेन च नानार्थत्वव्यवहार इति भावः ॥ तत्र यदेति । एकशक्तित्वपक्षे त्वर्थभेदादुपचरितभेदाश्रयणमिति बोध्यम् ॥ ग्रामशब्दोऽयं बह्वर्थं इति तु मुख्यार्थमेव । अत्र सर्वार्थनिरूपितवृत्तीनां 'वर्तते' इत्येकवचनबोध्यत्वेनाभेदबोधनादेकशक्तित्वपक्षो भाष्यबोधितः । तत्र वर्तनक्रियाऽस्तिक्रियायाः कर्त्री । शालासमुदायादौ ग्रामशब्दस्य वृत्तिरस्तीत्यर्थः । वाटपरिक्षेपो नाम शालासमुदायरक्षणाय सर्वतो मार्गप्रतिरोधकं यत्परितः क्षिप्यते तदुच्यते ॥ सारण्यकससीमकवृत्तिस्त्वत्र न गृह्यते इत्याह—शुचाविति । सीमनीति च ॥ ७ ॥

(७ अनुनासिकसंज्ञासूत्रम् ॥ १ । १ । ४ आ. ५)

मुखनासिकावचनोऽनु-

नासिकः ॥ १ । १ । ८ ॥

(मुखनासिकावचनशब्दार्थनिरूपणम्)

(आक्षेपभाष्यम्)

किमिदं 'मुखनासिकावचनः' इति ?

(प्रदीपः) **मुखनासिकावचनोऽनुनासिकः ॥ ८ ॥** प्राण्यङ्गत्वात्समाहारद्वन्द्वे ह्रस्वत्वेन भाव्यम्, 'अवचनं' इति नञ्-समासाश्रयणेऽर्थो न संगच्छते इति **प्रश्नः-किमिदमिति ॥**

(उद्योतः) मुखना० ॥ ८ ॥ प्राण्यङ्गत्वादिति । एतेनेतरेतरयोगद्वन्द्वे रूपसिद्धिरित्यपास्तम् ॥ अर्थ इति । अभिमतोऽर्थ इत्यर्थः ॥

(समाधानभाष्यम्)

मुखं च नासिका च-मुखनासिकम् । मुखनासिकं वचनमस्य सोऽयं मुखनासिकावचनः ॥

(आक्षेपभाष्यम्)

यद्येवं 'मुखनासिकवचनः' इति प्राप्नोति ॥

(समाधानभाष्यम्)

निपातनाद्दीर्घत्वं भविष्यति ॥

(प्रदीपः) **निपातनादिति ।** प्रसङ्गेनास्य लौकिकशब्दस्य साधुत्वं क्रियते । निपातनानां च बाधकत्वात् 'मुखनासिकवचनः' इति न भाव्यम् । अबाधकत्वपक्षे तु भाव्यमेव ॥

(उद्योतः) सौत्रत्वादिति कुतो नोक्तमित्यत आह—**प्रसङ्गेनेति ॥ अबाधकत्वेति ।** पक्षे त्वित्यनेनाबाधकत्वस्वीकर्तृवृत्तिमतमसङ्गतमित्युक्तम् । भाष्यकृदसंमतरूपापत्तेः । **बाधकान्येव निपातनानीति सर्वादिसूत्रे** भाष्ये उक्तेः ॥

(समाधानान्तरभाष्यम्)

अथवा-मुखनासिकं-आवचनमस्य सोऽयं मुखनासिकावचनः ॥

(आक्षेपभाष्यम्)

अथ किमिदं 'आवचनं' इति ?

(समाधानभाष्यम्)

ईषद्वचनं-आवचनम् । किंचिन्मुखवचनं, किंचिन्नासिकावचनम् ।

(प्रदीपः) **ईषद्वचनमिति ।** भागस्य मुखेनोच्चारणात् भागस्य नासिकया । अस्मिन्पक्षे 'मुखनासिकवचनः' इत्यपि भवति । यो हीषदुच्यते स उच्यत एव । यथा-ईषच्छुक्लोऽपि शुक्ल एव ॥

(उद्योतः) **अस्मिन् पक्ष इति ।** आङ्रहितस्येति शेषः । वस्तुत आवपक्षैकवाक्यतया आङ्रहितैतत्पदाभ्यां समासस्यानभिधानमेवेत्याहुः ॥ ननु भागस्य मुखाद्युच्चार्यत्वेन मुखनासिकं वचनमुच्चारणकरणं यस्य वर्णस्येत्यर्थको मुखनासिकवचन इति प्रयोगस्तत्रासङ्गतोऽत आह—**यो हीति ॥**

(समासान्तरभाष्यम्)

मुखद्वितीया वा नासिका वचनमस्य सोऽयं मुखनासिकावचनः ॥

(प्रदीपः) **मुखद्वितीयेति ।** मुखसहाया-इत्यर्थः । तत्र नासिका मुखसाहचर्यान्मुखशब्देनोच्यते । मुखं च तन्नासिका च-मुखनासिका, सा वचनमस्येति ॥

(उद्योतः) **सहायेति ।** अव्युत्पन्नो द्वितीयशब्दः सहायवाचीत्यर्थः ॥ शाकपार्थिवादित्वादुत्तरलोपे शब्दानित्यत्वापत्तिरत आह—**तत्रेति ॥** परन्त्विदं चिन्त्यं, भाष्यकृतैवंरीत्या तदप्रत्याख्यानात् ॥

(समाधानान्तरभाष्यम्)

मुखोपसंहिता वा नासिका वचनमस्य सोऽयं मुखनासिकावचनः ॥

(प्रदीपः) **मुखोपसंहितेति ।** मुखस्य च नासिकायाश्चान्तरालं स्थानान्तरमेवानुनासिकस्य दर्शयति । तत्र सामीप्यान्मुखं च तन्नासिका चेत्युभाभ्यामन्तरालं व्यपदिश्यते । पदसंस्कारपक्षे मुखनासिकापदनिरपेक्षं 'वचनं'इत्येतत्पदं लिङ्गसर्वनामनपुंसकाश्रयेण संस्क्रियते । पश्चात्स्त्रीत्वस्य पदान्तरसंबन्धेन प्रतीयमानत्वाद्बहिरङ्गत्वान्ङीप्प्रत्ययो न भवति । यदा तु स्त्रीत्वाश्रयेण 'वचनी' इतिपदं व्युत्पाद्यते तदा मुखनासिकावचनीक इति भवत्येव ॥ अत्र चानेकं दर्शनम् । अनुनासिकस्य पूर्वः परो वा भागो मुखेनोच्चार्यते, भागो नासिकया । तत्र नासिकावचनभागानुरागवशात् मुखवचनोऽपि भागो नासिकावचन इव लक्ष्यते । यथा-सँय्यन्तेत्यत्रानुनासिकयकारानुरागात् अकारोऽनुनासिक इव प्रतिभाति ॥ अत्र च प्रासादवासिन्यायो नास्ति, भागस्यैव मुखेन नासिकया चोच्चारणात् न तु समग्रस्य ॥ अन्येषां तु दर्शनं-मुखनासिकान्तरालं स्थानान्तरमेवास्य-इति । अत्रापि नास्ति प्रासादवासिन्यायः ॥ यदा सर्व एव वर्णो मुखेनोच्चार्यते नासिकया च तदा प्रासादवासिन्यायेन भाष्यकारो मुखग्रहणं प्रत्याचष्टे । यथा-भ्राष्ट्रेणोखया च पक्वः सूप उभाभ्यां व्यपदिश्यते ॥

(उद्योतः) **मुखस्य चेति ।** उपशब्दसामर्थ्यादिति भावः । यद्यपि वचनशब्दे कर्मणि ल्युटि मुखनासिकेनावचनः-मुखनासिकया वचन इति वा तत्पुरुषोऽपि वक्तुं शक्यः, तथापि कर्मणि तस्य बाहुलकलभ्यत्वात्करणे ल्युटा बहुव्रीहिरेवाश्रितो भाष्ये ॥ तत्रान्त्ययोर्नासिकाशब्दसामानाधिकरण्यात्स्त्रीत्वविशिष्टस्यैव करणत्वेन ल्युटि ङीपि नद्यृतश्चेति कबापत्तिरत आह—**पदसंस्कारेति ॥** भागस्य मुखेनोच्चारणाननुभवादाह—**अत्रेति ।** तस्यादित इति सूत्रस्वरसाद्वर्णानां सखण्डत्वमित्याशयः ॥ ये तु तत्तद्देशावच्छिन्नवाय्वभिघातस्य तत्तद्वर्णजनकत्वात्स्थानानां करणत्वमेव । स्थानव्यवहारस्तु वर्णजनकवायुसंयोगाधारत्वाद्वर्णाधारत्वमारोप्य । अत एवोत्तरसूत्रे भाष्ये-**अखन्त्यनेन वर्णानित्यास्यमिति** करणे व्युत्पत्तिर्दर्शितेति वदन्ति । तन्मते प्रासादवासिदृष्टान्तासङ्गतेराह—**भ्राष्ट्रेण चेति ॥** एतेन कण्ठादिकं तु स्थानं, नासिका तु करणमिति मन्दोक्तमपास्तम् । अत एवात्र सूत्रे हरिणा—"स हि वर्णो न मुखेनैव

नापि नासिकयैव चात्मवृत्तिं लभते, किं तु वायुनाऽनुपरत-
शक्तिनाऽन्यतरकरणमभिहत्यान्यतरकरणेऽभिहन्यमाने आ-
त्मव्यक्तिं लभते" इत्युक्तम् ॥

(पदकृत्यनिर्वचनायाक्षेपभाष्यम्)

अथ मुखग्रहणं किमर्थम् ?

(समाधानभाष्यम्)

'नासिकावचनोऽनुनासिकः' इतीयत्युच्यमाने यमानुस्वाराणामेव प्रसज्येत । मुखग्रहणे पुनः क्रियमाणे न दोषो भवति ॥

(प्रदीपः) यमानुस्वाराणामेवेति । प्रासादवासिन्यायानवतारपक्ष इति भावः । तत्र विधिप्रदेशेषु यमानुस्वारा एवादेशाः स्युः । 'विड्वनोरनुनासिक स्यात्' इत्यादिषु त्वनुवादप्रदेशेषु यमानुस्वाराणामसंभवादप्रतिपत्तिः स्यात् ॥

(उद्द्योतः) यमो नाम वर्गपञ्चमे परे वर्गाद्यचतुष्टयान्यतमसदृशो वर्णः ॥ आदितश्चत्वारो वर्णा इति विवरणेऽपि चतुःशब्दस्य चतुःसदृशे लक्षणा बोध्या। अत एवायोगवाहत्वप्रतिपादकह्यवरट्सूत्रस्थभाष्याविरोधः ॥ न्यायानवतारेति । कचटतपानामेवेत्येवकारोऽप्यत्रैव पक्षे-नासिकाया आस्याद्बाह्यत्वपक्षे च बोध्यः ॥ अप्रतिपत्तिरिति । अत्र विड्वनोर्मम इति वक्तुं शक्यम् । यरोऽनुनासिक इत्यत्र त्वप्रतिपत्तिः, तत्र ञमि ञम्वेत्युक्ते सकलेष्टासिद्धेः ॥

(आक्षेपभाष्यम्)

अथ नासिकाग्रहणं किमर्थम् ?

(समाधानभाष्यम्)

'मुखवचनोऽनुनासिकः' इतीयत्युच्यमाने क-च-ट-त-पानामेव प्रसज्येत । नासिकाग्रहणे पुनः क्रियमाणे न दोषो भवति ॥

(प्रदीपः) कचटतपानामिति । 'पक्त' इति चकारलोपप्रसङ्गः, 'ओदनपक्' इत्यत्र 'अनुनासिकस्य क्विझलोः क्ङिति' इति दीर्घप्रसङ्गः ॥

(उद्द्योतः) चकारलोपेति । निष्ठातत्वकुत्वयोरसिद्धत्वात् पचेरनुनासिकोपदेशत्वादुदात्तोपदेशवनतीत्यनेनेति भावः ॥

(मुखग्रहणप्रत्याख्यानभाष्यम्)

मुखग्रहणं शक्यमकर्तुम् ॥

(आक्षेपभाष्यम्)

केनेदानीमुभयवचनानां भविष्यति ?

(समाधानभाष्यम्)

प्रासादवासिन्यायेन । तद्यथा-केचित्प्रासादवासिनः, केचित् भूमिवासिनः, केचिदुभयवासिनः । ये प्रासादवासिनः, गृह्यन्ते ते प्रासादवासिग्रहणेन । ये भूमिवासिनः, गृह्यन्ते ते भूमिवासिग्रहणेन । ये उभयवासिनः, गृह्यन्त एव ते प्रासादवासिग्रहणेन भूमिवासिग्रहणेन च ॥

एवमिहापि केचिन्मुखवचनाः, केचिन्नासिकावचनाः, केचिदुभयवचनाः । तत्र ये मुखवचनाः, गृह्यन्ते ते मुखग्रहणेन । ये नासिकावचनाः, गृह्यन्ते ते नासिकाग्रहणेन । ये उभयवचनाः, गृह्यन्त एव ते मुखग्रहणेन नासिकाग्रहणेन च ॥

(प्रदीपः) प्रासादवासिन्यायेनेति । अयं न्यायः क्रियाशब्देष्वेव, न रूढिशब्देषु ॥

(उद्द्योतः) ननु प्रासादवासिन्यायेन मुखग्रहणप्रत्याख्यानवत्तन्त्रमेव कुतो न प्रत्याख्यायते—इत्यत आह—अयमिति । योगेन ह्युभयग्रहणं स रूढिषु नास्तीत्यर्थः । अनुनासिकशब्दस्य च रूढिशब्दत्वम् । तस्य क्रियाशब्दत्वं तु वक्तुमशक्यम्, अनु—पश्चा-
न्नासिका व्याप्रियते यस्मिन्निति योगस्य यमङ्ङणेषु निरूपयितुमशक्यत्वात् । विनिगमनाविरहेण युगपदुभयोर्व्यापृतेः ॥ एतेनानुपश्चान्नासिकां गत इत्यर्थको नासिकामनुगत इति योगोऽपि परास्तः । यथाकथंचिद्योगोपपादने तु रूढिरेव फलितेति दिक् ॥ ८ ॥

(आक्षेपभाष्यम्)

भवेदुभयवचनानां सिद्धम् । यमानुस्वाराणामपि प्राप्नोति ॥

(समाधानभाष्यम्)

नैव दोषो न प्रयोजनम् ॥

(प्रदीपः) नैव दोष इति । अनुवादे तावत् यमानुस्वाराणामसंभव एव । विधावप्यान्तरतम्यान्मुखवचनस्योभयवचनो भविष्यति, न तु केवलनासिकावचनः ॥ ८ ॥

(अन्योन्याश्रयपरिहारायाक्षेपभाष्यम्)

इतरेतराश्रयं तु भवति ।

का इतरेतराश्रयता ?

सतोऽनुनासिकस्य संज्ञया भवितव्यम्, संज्ञया च नामानुनासिको भाव्यते, तदितरेतराश्रयं भवति । इतरेतराश्रयाणि च कार्याणि न प्रकल्पन्ते ॥

(सिद्धान्तसमाधानभाष्यम्)

अनुनासिकसंज्ञायामितरेतराश्रये उक्तम् ।

किमुक्तम् ?

सिद्धं तु नित्यशब्दत्वात् इति ।

नित्या शब्दाः । नित्येषु च शब्देषु सतोऽनुनासि-
कस्य संज्ञा क्रियते, न संज्ञयाऽनुनासिको भाव्यते ॥

यदि तर्हि नित्याः शब्दाः, किमर्थं शास्त्रम् ?

(सिद्धान्तभाष्यवार्तिकम्)

किमर्थं शास्त्रमिति चेत्-निवर्तकत्वात्सिद्धम् ॥

(भाष्यम्)

निवर्तकं शास्त्रम् ।

कथम्?

आम्नायविशेषेणोपदिष्टोऽननुनासिकः । तस्य सर्वत्राननुनासिकबुद्धिः प्रसक्ता, तस्यानेन निवृत्तिः क्रियते-छन्दस्यचि परत आङोऽननुनासिकस्य प्रसङ्गेऽनुनासिकः साधुर्भवतीति ॥ मुखनासिकावचनोऽनुनासिकः ॥ ८ ॥

(सवर्णसंज्ञाप्रकरणम्)

(८ सवर्णसंज्ञासूत्रम् ॥ १ । १ । ४ आ. सू. ६)

तुल्यास्यप्रयत्नं सवर्णम् ॥ १ । १ । ९ ॥

(तुल्यास्यप्रयत्नपदार्थनिरूपणम्)

(विग्रहदर्शकभाष्यम्)

तुलया संमितं तुल्यम् । आस्यं च प्रयत्नश्च-आस्यप्रयत्नम् । तुल्यास्यं तुल्यप्रयत्नं च सवर्णसंज्ञं भवति ॥

(प्रदीपः) तुल्यास्यप्रयत्नम् ॥ ९ ॥ चत्वारोऽत्र पक्षाः संभवन्ति—द्वन्द्वगर्भो बहुव्रीहिः, त्रिपदो बहुव्रीहिः, तुल्यास्यशब्दयोस्तत्पुरुषस्ततो बहुव्रीहिः, आस्यप्रयत्नशब्दयोस्तत्पुरुषस्ततो बहुव्रीहिरिति । तत्र द्वन्द्वगर्भो बहुव्रीहिरिति पक्षे वार्तिकस्यावतार इति तमेव भाष्यकारः पूर्वं दर्शयति—तुलया संमितमिति । व्युत्पत्त्यर्थमेव तुलोपादीयते । रूढिशब्दस्त्वयं सदृशपर्यायः । यथा-प्रवीणः-कुशलः-प्रतिलोमः-अनुलोम इत्यवयवार्थाभावः, एवं तुल्यशब्देऽपि ॥

(उद्द्योतः) तुल्यास्यप्र० ॥ ९ ॥ तत्पुरुष इति । तुल्यास्यशब्दयोर्मयूरव्यंसकादित्वात्पूर्वपदार्थप्रधानस्तत्पुरुषः । आस्यप्रयत्नशब्दयोश्च साधनं कृतेत्यनेन समासः ॥ ननु स्थानादिकं न तुलया संमीयतेऽत आह—व्युत्पत्त्यर्थमेवेति ॥

(जिज्ञासाभाष्यम्)

किं पुनरास्यम्?

(प्रदीपः) किं पुनरास्यमिति । किं मुखम्, अथ तत्रत्यं ताल्वादिकं स्थानमिति प्रश्नः ॥

(उद्द्योतः) किं मुखमिति । तद्धितान्तातद्धितान्तास्यशब्दविषयकसन्देह इत्याशयः ॥

(समाधानभाष्यम्)

लौकिकमास्यम् । ओष्ठात्प्रभृति प्राक्काकलकात् ॥

(प्रदीपः) लौकिकमिति । पशुः-अपत्यं-देवता-इत्यादिवत् प्रसिद्धमित्यर्थः ॥ यद्यपि ताल्वादिकमपि लौकिकमास्यम्, तथापि तत्र योगवशादास्यशब्दो वर्तत इति झटिति न तत्प्रसिद्धमिति मुखमेव प्रसिद्धत्वाल्लौकिकमुक्तम् । तस्यैव च प्राधम्यात् ग्रहणं युक्तमित्यर्थः ॥ ओष्ठादिति । काकलकं नाम ग्रीवायामुन्नतप्रदेशः ॥

(उद्द्योतः) तद्धितान्तमपि लौकिकमेव न वैदिकमित्यत आह—पशुरिति ॥ झटिति—पदश्रवणमात्रेणेत्यर्थः ॥

(आक्षेपभाष्यम्)

कथं पुनरास्यम्?

(प्रदीपः) कथं पुनरिति । यदि निमित्तवशात्प्रवर्तते ततस्ताल्वादिष्वपि प्रवर्तिष्यत इति प्रश्नः ॥

(उद्द्योतः) निमित्तवशात्—अवयवार्थवशात् ॥

(समाधानभाष्यम्)

अस्यन्त्यनेन वर्णानिति-आस्यम् ॥

अन्नमेतदास्यन्दत इति वा-आस्यम् ॥

(प्रदीपः) अस्यन्त्यनेनेति । सत्यपि निमित्ते रूढिवशान्मुखे एव वर्तते न ताल्वादिष्वित्यर्थः । 'कृत्यल्युट–' इति करणे ण्यत् । असनमत्रव्यक्तिस्फोटपक्षेऽभिव्यक्तिः, जातिस्फोटपक्षे तूत्पत्तिः ॥ अन्नमेतदिति । आङ्पूर्वात्स्यन्दतेः 'अन्येष्वपि दृश्यते' इति डः । एतत्–आस्यं कर्म, अन्नं कर्तृ । आस्यन्दते-द्रवीकरोति, अन्नप्रक्षेपेण मुखस्य द्रवत्वोत्पादनात् ।

(उद्द्योतः) जातिस्फोटेति । 'वर्णान्' इति वर्णपदं बोधकपरम् । तत्र जातेर्बोधकत्वे तस्या नित्यत्वादभिव्यक्तिः-असनं, तदाश्रयव्यक्तीनां वाचकत्वे तु-उत्पत्तिरिति भावः । अत एव वर्णानिति बहुवचनं सङ्गच्छते । एकैव व्यक्तिस्तत्तद्रूपेणाभिव्यक्ता वाचिकेति पक्षे तदसङ्गतिः स्पष्टैव ॥ क्वचित्तु 'व्यक्तिस्फोटपक्षेऽभिव्यक्तिः । जातिस्फोटपक्षे तूत्पत्तिः' इति पाठः ॥ अयमेव सांप्रदायिकः पाठः ॥ 'एकैव व्यक्तिर्वाचिका कत्वादिकं तु ध्वनिनिष्ठं ध्वनिविशेषव्यङ्ग्यं वा । सा च नित्या' इति व्यक्तिस्फोटवादः, तदाऽभिव्यक्तिः स्पष्टैव । बहुवचनं त्वेकस्यैव बहुरूपत्वादारोपितबहुत्वमादाय नेयम् ॥ 'व्यक्तयोऽनन्ता जन्याश्च । तत्र जातिरेव वाचिका' इति जातिस्फोटवादः, तदोत्पत्तिरित्यर्थः ॥ अन्येष्वपीति । वृत्तिग्रहणाद्धात्वन्तरादपि स इति भावः ॥

(आक्षेपभाष्यम्)

अथ कः प्रयत्नः?

(प्रदीपः) अथ कः प्रयत्न इति । किं प्रयतनं-प्रयत्नः, अथ प्रारम्भो यत्नस्येति प्रश्नः ॥

(समाधानभाष्यम्)

प्रयतनं प्रयत्नः । प्रपूर्वाद्यततेर्भावसाधनो नङ् प्रत्ययः ॥

(प्रदीपः) भावसाधन इति । भावेऽभिधेये नङ्प्रत्ययः क्रियते । तेन नशब्दस्येह भावः साधनं भवति ॥

(उद्द्योतः) ननु साधनशब्देन कारकशक्तिरभिधीयते-इति भावस्य साधनत्वमनुपपन्नमत आह—भावे इति ॥ नङ्–'यजयाच–' इत्यनेन ॥

(आक्षेपभाष्यम्)

यदि लौकिकमास्यम्, किमास्योपादाने प्रयोजनं सर्वेषां हि तत्तुल्यम्भवति?

(प्रदीपः) किमास्योपादान इति । आस्य एव सर्ववर्णानां निष्पादादिति भावः ॥ नासिकाऽपि न बाह्या वर्णोत्पत्तिनिमित्तम् । किं तर्हि? आस्यान्तश्चर्म विततमस्ति पणवचर्मवत्, तत्संबद्धा रेखा नासिका । तस्यां वाय्वभिघाताद्वर्णोत्पत्तिः । विसर्जनीयस्यैकीयमतेनोरस्यत्वात्सावर्ण्याभावेऽपि न दोषः ॥

(उद्द्योतः) ननु तुल्यावास्यप्रयत्नमात्रौ येषां जनकावित्यर्थे नासिकास्थानङञादिनिवृत्त्यर्थमास्योपादानं स्यादत आह—नासिकाऽपीति । एवं चास्यग्रहणे कृतेऽपि तद्व्यावृत्तिर्दुरुपपादेति भावः । वस्तुतस्तु अवधारणगर्भसमासे ह्रस्वाकारादिभिर्दीर्घाकारादीनां सावर्ण्यानापत्तिः । तज्जनकवायुसंयोगानामपि तुल्यत्वात् । अवधारणागर्भसमासे त्वनुनासिकव्यावृत्तिरपि दुरुपपादैवेति भाष्याशयः ॥ एवंच नासिकाया बाह्यत्वेऽपि न क्षतिः । अत एव मुखनासिकेति सूत्रे मुखं च नासिका चेति-मुखद्वितीया नासिकेति च विग्रहप्रदर्शनं भाष्ये । न तु अवयवावयविविषये एवं प्रयोगः सचेतसाम् ॥ सहस्तो देवदत्त इत्यादौ विद्यमानवाची सहशब्दः । अत एव मुखवचनोऽनुनासिक इतीयत्युच्यमाने कचटतपानामेव प्रसज्येतेति भाष्ये 'एव'शब्दः सङ्गच्छते । अन्यथा यमादीनां ञादीनां च मुखवचनत्वात्तदसङ्गतिः स्पष्टैव । आस्यानन्तर्गतत्वे तु न दोषः, मुखमात्रवचनत्वाभावात् । प्रासादवासिन्यायप्रदर्शकभाष्येणापि ध्वनितमेतत् । कैयटोक्तास्यान्तर्गतत्वपक्षे तु सूत्रे मुखपदं मुखावयवपरम् । ब्राह्मणवसिष्ठन्यायेन च नासिकातिरिक्तावयवग्रहणम् । एवकारश्चाप्यर्थः । दृष्टान्तोऽप्येकांशेन बोध्य इति ॥ नन्वेवमपि विसर्जनीयव्यावृत्तये तत्स्यादत आह—विसर्जनीयस्येति । सतश्चान्येषां कण्ठादिस्थान एवेति भावः ॥ उरस्यमतेऽप्याह—सावर्ण्याभावेऽपीति ॥

(समाधानभाष्यम्)

वक्ष्यत्येतत्—'प्रयत्नविशेषणमास्योपादानम्' इति॥

(प्रदीपः) वक्ष्यतीति । नास्य परीक्षाऽवसर इति भावः ॥

(उद्द्योतः) ननु इदानीमेव किं नोच्यतेऽत आह—नास्येति ॥

(१२८ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ सवर्णसंज्ञायां भिन्नदेशेष्वतिप्रसङ्गः प्रयत्नसामान्यात् ॥ * ॥

(भाष्यम्)

सवर्णसंज्ञायां भिन्नदेशेष्वतिप्रसङ्गो भवति—अवगडदशाम् ।

किं कारणम्?

प्रयत्नसामान्यात् । एतेषां हि समानः प्रयत्नः ॥

(प्रदीपः) सवर्णसंज्ञायामिति । द्वन्द्वे प्रयत्नस्यास्येनाविशेषणान्मुखप्रयत्नयोस्तुल्यत्वाद्भिन्नस्थानानामपि प्रसङ्गः । भाष्ये शकारः प्रत्याहारपाठवशात्पठितः । अत्र प्रत्याहारे जबगडदानां प्राप्नोतीत्यर्थः । शकारस्य तु विवृतत्वात्स्पर्शानां स्पृष्टत्वादप्रसङ्ग एव । ततश्च 'ऊर्जः' इत्यादौ 'झरो झरि–' इति लोपप्रसङ्गः ॥

(उद्द्योतः) 'द्वन्द्वे प्रयत्नस्यास्येनाविशेषणात्' इत्यस्योपयोगश्चिन्त्यः ॥ अत्रेति । एतद्वर्णसमूहसाध्यप्रत्याहारे इत्यर्थः । ऊर्ज्=अन्नं, तस्माज्जातः—ऊर्जः ॥

(१२९ न्यासान्तरेण समाधानवार्तिकम् ॥ २ ॥)

॥ * ॥ सिद्धं त्वास्ये तुल्यदेशप्रयत्नं सवर्णम् ॥ * ॥

(भाष्यम्)

सिद्धमेतत् ।

कथम्?

आस्ये येषां तुल्यो देशः प्रयत्नश्च ते सवर्णसंज्ञा भवन्तीति वक्तव्यम् ॥

(आक्षेपभाष्यम्)

एवमपि किमास्योपादाने प्रयोजनम्, सर्वेषां हि तत्तुल्यम्?

(प्रदीपः) एवमपीति । आस्ये येषां तुल्यो देश इत्यास्येन देशो विशेष्यते । तत्र व्यभिचाराभावादास्येन देशस्य विशेषणमयुक्तमित्यर्थः ॥

(उद्द्योतः) आस्ये इति । देशविशेषणवैयर्थ्याभिप्रायेण प्रश्न इति भावः । न च नासिकाया आस्यानन्तर्गतत्वपक्षे तद्व्यावृत्त्यै देशविशेषणमावश्यकमिति वाच्यम् । अनुनासिकाकारादौ कण्ठादिषु वाय्वभिघातादभिव्यक्तेषु वर्णेषु नासिकाभिघातेनानुनासिक्यं धर्म उत्पद्यते-इत्यनुभवेन वृद्धिरादैजित्यस्य—'भेदकत्वाद् गुणस्येति वाच्यम् । आनुनासिक्यस्य भेदकत्वार्थं । तथैकोऽयमात्मा' इत्यादिभाष्यकैयटात् तथैव क्रमेण च तेषु नासिकाया देशत्वाभावस्य सूचनात् आस्यैऽपि तथैव-इत्यभिमानात् । देशपदेन ताल्वादिस्थानमेवोच्यते-इति ञमङणादिषु न दोषः ॥

(समाधानभाष्यम्)

प्रयत्नविशेषणमास्योपादानम् । सन्ति हि आस्याद्बाह्याः प्रयत्नाः, ते हापिता भवन्ति । तेषु सत्स्वसत्स्वपि सवर्णसंज्ञा सिद्धा भवति ।

के पुनस्ते?

विवारसंवारौ, श्वासनादौ, घोषवदघोषता, अल्पप्राणता-महाप्राणता-इति ।

तत्र वर्गाणां प्रथमद्वितीया विवृतकण्ठाः श्वासानुप्रदाना अघोषाः । एके—अल्पप्राणाः, अपरे-महाप्राणाः ।

तृतीयचतुर्थाः संवृतकण्ठा नादानुप्रदाना घोषवन्तः । एके—अल्पप्राणाः, अपरे-महाप्राणाः ।

यथा तृतीयास्तथा पञ्चमाः, आनुनासिक्यवर्ज्यम् । आनुनासिक्यमेषामधिको गुणः ॥

(प्रदीपः) **प्रयत्नविशेषणमिति** । तस्य संभवव्यभिचारसद्भावादित्यर्थः । बाह्यप्रयत्नव्युदासाच्चत्वार आभ्यन्तरा गृह्यन्ते—स्पृष्टतेषत्स्पृष्टताविवृततासंवृतताख्याः ॥

(उद्योतः) भाष्ये—**प्रयत्नविशेषणमिति** । **देशप्रयत्न**मिति द्वन्द्वस्तु सौत्रत्वात्साधुरिति भावः ॥ **स्पृष्टतेत्यादि** । आस्यान्तर्गततत्तत्स्थानेषु जिह्वाग्रादीनां वर्णाभिव्यक्तिजनकस्पर्शेषत्स्पर्शदूरावस्थानसमीपावस्थानरूपाभ्यन्तरकार्यकारिप्रयत्नविशेषा एतैः पदैरुच्यन्ते । तेषां चास्यवृत्तित्वमास्यान्तर्गततत्तत्स्थानेषु वायुसंयोगजनकत्वेनेति बोध्यम् । आस्ये—इत्यस्य 'यत्कार्यं तज्जनकः' इति शेषो वा ॥ भाष्ये—**ते हापिता इति** । सवर्णसंज्ञा स्वनिमित्तत्वेन बाह्यप्रयत्नाञ्जहाति-इति तया ते स्वनिमित्तत्वं हापिता इत्यर्थः ॥ **विवारसंवारौ**=कण्ठबिलस्य विकाससङ्कोचौ । विवृतः कण्ठो यैः, श्वासोऽनुप्रदीयते यैरित्यर्थः । **एके**-उक्तवाक्ययोः प्रथमोपात्ताः । **नादः**—वर्णोत्पत्त्यनन्तरभावी अनुरणनरूपः शब्दः ॥ **यथा तृतीया** इत्यनेन तेषामल्पप्राणत्वं बोधितम् ॥ देशविशेषणमप्यास्यग्रहणमावश्यकमिति गूढाशयेनाह—भाष्ये—**आनुनासिक्यमेषामधिको गुण इति** । अयं भावः—अत्र देशपदेन ताल्वादिस्थानमुच्यते । स्थानशब्देन च योगरूढ्या वर्णाभिव्यक्तिजनकवायुसंयोगानुयोगि ताल्वाद्युच्यते । तत्र यद्यपि अकारादीनां गुणमात्रजनिका नासिका, स्वरूपस्य कण्ठादिभिरेवाभिव्यक्तिसिद्धेः; तथापि ञादीनां स्वरूपस्य न केवलताल्वादिना नापि केवलनासिकयाऽभिव्यक्तिरिति विनिगमनाविरहादुभयावच्छिन्नवायुसंयोगस्यैव तज्जनकत्वात्तेषां नासिकाऽपि स्थानम् । न चैवं त्वङ्करोषीत्यादौ चरितार्थं परसवर्णशास्त्रं संयन्तेत्यादौ न प्रवर्तेत । उक्तरीत्या यादीनां नासिकास्थानत्वाभावेन स्थानत आन्तर्याभावादिति वाच्यम । **स्थानेऽन्तरतमे** इति सप्तम्यन्तपाठस्य दूषितत्वेनास्या युक्तेर्गर्भस्रावात् ॥ अनुनासिकाकारादीनामपि सा स्थानमिति त्वयुक्तमेव । एवं हि उत्पादकसामग्रीभेदात्कङ्योरिव स्वरूपभेदस्यैवापत्तौ अभेदकगुणपक्षेऽपि निरनुनासिकैः सानुनासिकग्रहणानापत्तिः । एवं च यावत्स्थानसाम्ये सवर्णसंज्ञा-इति सिद्धान्ते नासिकारूपदेशभेदात्ककादीनामप्राप्तसावर्ण्यसिद्धये आस्येन देशविशेषणमावश्यकम् । नासिकाया आस्यान्तर्गतत्वेऽपि **मुखनासिके**तिसूत्रे नासिकातिरिक्तावयवकमुखस्यैव ग्रहणेन तत्साहचर्यादत्राप्यास्यपदेन तादृशस्यैव ग्रहणं बोध्यम् । अन्यथाऽत्र स्थाने एतत्कथनवैयर्थ्यापत्तिः । आस्यग्रहणव्यावर्त्यानां सावर्ण्यानुपयुक्तानां प्रदर्शनमेव ह्यत्र प्रक्रान्तम् ॥ न चेदं प्रयत्नविशेषणास्यग्रहणव्यावर्त्यमेवास्तु, अनुनासिकयकारादीनां ञादिभिः सावर्ण्यं च व्यावर्त्यम्, तत्फलं च तञ्छुङ्क्ते तन्नमतीत्यादौ **अनुस्वारस्य ययी**त्यनेन यकारलकारयोरनुनासिकयोरभाव इति **वाच्यम्** । अनुस्वारस्य नासिकास्थानत्वेन स्थानतोऽन्तरतमयोर्ञनयोरेव प्रवृत्तेः । अनुनासिकयादीनां तु उक्तरीत्या न नासिका स्थानमित्यदोषात् । इदमेव ध्वनयितुं **गुण** इत्युक्तम् । गुणपदेन च सावर्ण्यानुपयोगिन आन्तरतम्यपरीक्षोपयोगिनो विवारादय उच्यन्ते । एवं च तत्साहचर्यादत्रापि गुणशब्दप्रयोगः । अत एव बाह्यप्रयत्नानुपक्रम्याऽमोनुनासिका न ह्रावितिं शिक्षायामुक्तम् । अत **एवोदात्तादिभिः सहैकादश बाह्यप्रयत्ना** इति कैयटो वक्ष्यति । उदात्तादीनामपि वृद्धिसंज्ञासूत्रशेषे गुणत्वेन व्यवहारात् । अत एव '**एवमप्यवर्णस्य सवर्णसंज्ञा न प्राप्नोति । बाह्यं ह्यास्यात्स्थानमवर्णस्य' 'एवमपि व्यपदेशो न प्रकल्पते—आस्ये येषां तुल्यो देशः'** इति भाष्यं स्वरसतः सङ्गच्छते । अन्यथा प्रयत्नविशेषणमात्रस्योक्तेर्देशविशेषणत्वाभावेन तदसङ्गतिः स्पष्टैव । आस्येन देशविशेषणाभावान्न दोष इत्येव वक्तव्ये **सर्वमुखे**त्यादिसमाधानस्यापि निर्दलत्वापत्तिश्च ॥ '**एके**' इत्यनेन सर्वमते तु कण्ठस्थानमिति ध्वनयति ॥

(आक्षेपभाष्यम्)

एवमप्यवर्णस्य सवर्णसंज्ञा न प्राप्नोति ।
किं कारणम् ?
बाह्यं ह्यास्यात्स्थानमवर्णस्य ॥

(प्रदीपः) **बाह्यं ह्यास्यादिति** । काकलकस्याधस्तादुपजत्रुस्थानमवर्णस्यैक इच्छन्ति । सति च बाह्यदेशसंभवे तद्व्यवच्छेदायास्येन देशो विशेष्यत इति **प्रश्नः** ॥

(समाधानभाष्यम्)

सर्वमुखस्थानमवर्णमेक इच्छन्ति ॥

(प्रदीपः) **सर्वमुखेति** । अवर्णनिष्पत्तौ सर्वमेव मुखं व्याप्रियत इति नास्य बाह्यस्थानता ॥

(आक्षेपभाष्यम्)

एवमपि व्यपदेशो न प्रकल्पते—'आस्ये येषां तुल्यो देशः' इति ॥

(प्रदीपः) **एवमपीति** । अवर्णस्यास्यमेव देशो न त्वास्ये देशः ॥

(समाधानभाष्यम्)

व्यपदेशिवद्भावेन व्यपदेशो भविष्यति ॥

(प्रदीपः) **व्यपदेशिवद्भावेनेति** । सर्वावस्थायुक्तमास्यमास्यशब्देनोच्यते, देशशब्देन तु विशिष्टैवावस्था वर्णोत्पादनहेतुः । तत्र बुद्धिकृतभेदाश्रयो व्यपदेशः ॥

(आक्षेपभाष्यम्)

सिध्यति । सूत्रं तर्हि भिद्यते ॥

(सिद्धान्तिसमाधानभाष्यम्)

यथान्यासमेवास्तु ॥

(आक्षेपस्मारकभाष्यम्)

ननु चोक्तम्-* सवर्णसंज्ञाया भिन्नदेशेष्वतिप्रसङ्गः प्रयत्नसामान्यात् * इति ॥

(सिद्धान्तिसमाधानभाष्यम्)

नैष दोषः । न हि लौकिकमास्यम् ।
किं तर्हि ?
तद्धितान्तमास्यम् । आस्ये भवं-आस्यम्, "शरीरावयवाद्यत्" ।
किं पुनरास्ये भवम् ?
स्थानं करणं च ॥

(प्रदीपः) **नहीति** । प्राथमकल्पिकमित्यर्थः । यौगिकस्य

तु व्यवहितस्य ग्रहणम् ॥ **स्थानमिति** । ताल्वादि ॥ **करणमिति** । स्पृष्टतादि, जिह्वाया अग्रोपाग्रमध्यमूलानि वा ॥ यद्येवं प्रयत्नग्रहणं न कर्तव्यं, तस्याप्यास्ये भवत्वादास्यग्रहणेन ग्रहणात् । सत्यमेतत्, प्रत्येकं तु व्यापारनिरासार्थमुभयोरुपादानम् । तेन द्वयोस्तुल्यत्वे सवर्णसंज्ञा भवति ॥

(उद्द्योतः) व्यवहितस्येति । यद्यपि रूढियोगापहारिणी, तथाप्यास्यपदोपादानसामर्थ्याद्व्यवहितस्यापि ग्रहणमिति भावः ॥ **ताल्वादीति** । शिक्षायां तेन रूपेणैव वर्णस्थानत्वकथनादिति भावः । एतेन ताल्वादिपूर्वाधरभागभेदादुदात्तादीनां सवर्णसंज्ञा न प्राप्नोतीत्यपास्तम् । आस्यमवच्छेदकत्वेन तद्रूपावच्छिन्नस्यैव ग्रहणेनादोषात् ॥ ननु प्रयत्नपदेनैव तद्ग्रहणसिद्धिरत आह—**जिह्वाया अग्रेत्यादि** ॥ **प्रत्येकं त्विति** । प्रत्येकनिरूपितसादृश्यग्रहणनिरासार्थमित्यर्थः । यद्यपि ज्ञापकेनापि प्रत्येकव्यापारनिरासः सुकरः, तथापि यावदास्यमैक्यविवक्षायां ह्रस्वदीर्घयोः सावर्ण्यानापत्तिः ॥ तत्तज्जनकवायुसंयोगानामतुल्यत्वात् । अतः प्रयत्नपदमास्यपदेन स्थानमात्रग्रहणार्थम् । **स्थानं करणं चेति** भाष्ये करणपदेन वायुसंयोगोऽपि । प्रयत्नग्रहणाच्च नातिप्रसङ्ग इति तात्पर्यम् । अत एव यावत्स्थानैक्यपरेण **'नैतौ तुल्यस्थानौ'** इति भाष्येण न विरोध इति दिक् ॥

(आक्षेपभाष्यम्)

एवमपि प्रयत्नोऽविशेषितो भवति ?

(प्रदीपः) **अविशेषित इति** । आस्येनेत्यर्थः । द्वन्द्वपक्ष एवात्र स्थित इति **प्रश्नः** । ततश्च बाह्याः प्रयत्ना न त्यक्ताः स्युः ॥

(समाधानभाष्यम्)

प्रयत्नश्च विशेषितः ।

कथम् ?

न हि प्रयतनं-प्रयत्नः ।

किं तर्हि ?

प्रारम्भो यत्नस्य-प्रयत्नः ॥

(प्रदीपः) **प्रारम्भो यत्नस्येति** । तत्र पूर्वं स्पृष्टतादयश्चत्वारः, पश्चान्मूर्द्धनि प्रतिहते-निवृत्ते प्राणाख्ये वायौ विवारादयो बाह्या एकादश प्रयत्ना उत्पद्यन्ते ॥

(उद्द्योतः) भाष्ये—**प्रारम्भो यत्नस्येति** निर्धारणे षष्ठी, जातौ चैकवचनम् । **आरम्भ** इति कर्मणि घञ् । यत्नानां मध्ये प्रथमं वर्णोत्पत्तेः पूर्वमारभ्यमाण इत्यर्थः ॥ अत्रापि नासिकाया अग्रहणमुपपादितरीत्यैवेति बोध्यम् । अत्रेदं बोध्यम्—शब्दप्रयोगेच्छयोत्पन्नप्रयत्नान्नाभिप्रदेशात्प्रेरितो वायुर्वेगान्मूर्धपर्यन्तं गत्वा ततः प्रतिनिवृत्तो यत्नविशेषसहायेन तत्तत्स्थानेषु जिह्वाग्रादिस्पर्शपूर्वकं तत्तत्स्थानान्याहत्य वर्णानभिव्यनक्ति । ततो यत्नविशेषसहायेन परावृत्तिसमये गलबिलादीनां विकासादीन्करोति । तत्र ये तत्तत्स्थानाभिघातका यत्नास्ते आस्यान्तर्गततत्तत्कार्यकारित्वात् **'आस्ये प्रयत्नाः'** इत्युच्यन्ते, **'आभ्यन्तराः'** इति **'प्रारम्भाः'** इति, च । गलबिलादिविकासादिकराश्चास्यबहिर्भूतदेशे कार्यकरत्वाद्बाह्या इति ॥ एवं मात्राकालिकत्वादिकमपि बाह्यत्वमदृष्टकृतमिति नाभिप्रदेशात्प्रेरकयत्न एव कश्चिद्विलक्षणोऽल्पवायुं प्रेरयति कश्चिदधिकमिति तस्य यत्नस्य वायुप्रेरणरूपकार्यमास्यबाह्यदेशमिति तस्यापि व्यावृत्तिरास्यपदेनोक्ता अउणसूत्रे भाष्ये ॥ मूर्ध्नि प्रतिहते वर्णोत्पत्तेः पूर्वं स्पृष्टतादयः, पश्चान्निवृत्ते प्राणाख्ये-इत्यन्वयः कैयटे । अत एव—

"सोदीर्णो मूर्ध्न्यभिहतो वक्त्रमापद्य मारुतः ।

"वर्णाञ्जनयते"

इति शिक्षया न विरोध इति दिक् ॥

(आक्षेपभाष्यम्)

यदि प्रारम्भो यत्नस्य-प्रयत्नः, एवमप्यवर्णस्य एङोश्च सवर्णसंज्ञा प्राप्नोति ?

(प्रदीपः) **एवमपीति** । संध्यक्षरेषु प्रथमभागस्याकारेण सादृश्यात्सवर्णसंज्ञाप्राप्तिरिति **प्रश्नः** ॥

(उद्द्योतः) भाष्ये—यदि प्रारम्भ इत्यत्र यदीत्यस्य यद्यपीत्यर्थः ॥ **अकारेणेति** । ततश्च स्वसवर्णाकारस्य तत्र सत्त्वेन तद्द्वारा तुल्यस्थानत्वेनावर्णैङोः सावर्ण्ये गव्यमित्यत्र यस्येति लोपप्रसङ्ग इत्यभिमानः ॥

(समाधानभाष्यम्)

प्रश्लिष्टावर्णावेतौ ॥

(प्रदीपः) **प्रश्लिष्टावर्णाविति** । नात्र भागविवेकोऽस्ति, पांसूदकवदित्यर्थः ॥

(उद्द्योतः) **पांसूदकेति** । प्रश्लिष्टाविसस्य प्रकर्षेण श्लिष्टौ—मिलितावित्यर्थः । ततश्च तदननुभवेन केवलताल्वादिस्थानकत्वेन च नानयोः सावर्ण्यप्राप्तिरिति भावः ॥

(आक्षेपभाष्यम्)

अवर्णस्य तर्हि ऐचोश्च सवर्णसंज्ञा प्राप्नोति ॥

(प्रदीपः) **अवर्णस्येति** । विभागोऽत्र सुलक्ष इति **प्रश्नः** ॥ ततश्च नाव्यमित्यत्र 'यस्य-' इति लोपप्रसङ्गः ॥

(उद्द्योतः) **विभागोऽत्रेति** । एवं च पूर्ववत्तयोः सावर्ण्यं प्राप्नोत्येवेत्यर्थः ॥

(समाधानभाष्यम्)

विवृततरावर्णावेतौ ॥

(उद्द्योतः) भाष्ये एतदुत्तरं—**विवृततरावर्णाविति** । एवं च तद्द्वारा तयोरपि विवृततरत्वेन प्रयत्नभेदावगमत्वेन न सावर्ण्यम् । आकारस्य ततोऽपि विवृततरत्वापत्तेनाप्यनयोर्न सावर्ण्यं फलाभावश्चेति भावः ॥

(आक्षेपभाष्यम्)

एतयोरेव तर्हि मिथः सवर्णसंज्ञा प्राप्नोति ॥

(प्रदीपः) **एतयोरिति** । ततश्च **'एत ऐ'** इत्यौकारोऽपि स्यात्, भाव्यमानस्यापि क्वचित्सवर्णग्रहणदर्शनात् ॥

(उद्द्योतः) **एतयोरेवेति** । यत्किञ्चित्स्थानसाम्ये सवर्णसंज्ञेत्यभिमानः ॥ क्वचित्—अदसोऽसेर्दादु दो म इत्यादौ ॥

(समाधानभाष्यम्)

नैतौ तुल्यस्थानौ ॥

(उद्योतः) भाष्ये—ऐचौ तुल्यस्थानाविति । वोर्लीति परसवर्णेरहितवद्वानासामितिनिर्देशात् यावत्स्थानसाम्यमत्र विवक्षितमिति भावः ॥ यत्त्वेषां समुदितं स्थानमिति । तत्र । "दन्त्योष्ठ्यो वः स्मृतो बुधैः । ए ऐ तु कण्ठ्यतालव्यौ" इति शिक्षायां प्रत्येकं तत्र भव इत्यधिकारस्यवदनापत्तेः । दन्त्योष्ठ्य इति पाठस्त्वसङ्गतः, शरीरावयवसमुदायस्य शरीरावयवत्वाभावात्, स्वाङ्गसमुदायस्य स्वाङ्गत्वाभाववत् । स्वजनकवायुसंयोगावच्छेदके कण्ठादौ स्वाधारत्वमारोप्य कण्ठे भव इत्याद्युपपत्तिः ॥ शरीरे मे वेदनेत्यत्रेयमेवेति दिक् ॥

(आक्षेपभाष्यम्)

उदात्तादीनां तर्हि सवर्णसंज्ञा न प्राप्नोति ॥

(उद्योतः) भाष्ये—उदात्तादीनां तर्हीति । यावत्स्थानैक्यवत् यावत्प्रयत्नैक्यविवक्षणादिति भावः ॥

(समाधानभाष्यम्)

अभेदका उदात्तादयः ॥

(प्रदीपः) अभेदका इति । लिङ्गेनैतत्प्रतिपादितम्—**न शक्ये एते स्वशब्दोपादानमन्तरेण कार्येषु भिन्नत्व** इति, तेन प्रारम्भभेदेऽप्युदात्तादीनां मिथः सवर्णसंज्ञा भविष्यति ॥

(उद्योतः) स्वशब्दाः=उदात्तादिशब्दाः । एवं चात्र प्रयत्नशब्देनोदात्तादीनां न ग्रहणमिति भावः ॥

(एकदेशिभाष्यम्)

अथवा किं न एतेन-प्रारम्भो यत्नस्य प्रयत्न इति ?

किं तर्हि ?

प्रयतनमेव-प्रयत्नः । तदेव च तद्धितान्तमास्यम् । यत्समानं तदाश्रयिष्यामः ।

किं सति भेदे ?

सतीत्याह । सत्येव हि भेदे सवर्णसंज्ञया भवितव्यम् ।

कुत एतत् ?

भेदाधिष्ठाना हि सवर्णसंज्ञा, यदि हि यत्र सर्वं समानं तत्र स्यात्, सवर्णसंज्ञावचनमनर्थकं स्यात् ॥

(प्रदीपः) यत्समानमिति । स्पृष्टत्वस्य समानत्वाद्वर्ग्याणां बाह्यप्रयत्नभेदेऽपि सवर्णसंज्ञा भविष्यति ॥ किं सतीति । स्पृष्टताद्यभेदाद्विवारादिभेदेऽपि यथा भवति तथा स्पृष्टतादिभेदेऽपि विवाराद्यभेदात्प्राप्नोतीति प्रश्नः ॥ सत्येवेति । 'झरो झरि' इत्येवान्यथा ब्रूयात् । यथासंख्यनिरासार्थं हि तत्र सवर्णग्रहणं कृतं 'शिण्ढि' इत्यत्र ढकारस्य ढकारे परतो लोपार्थम् । यदि च यत्र सर्वं समानं तत्रैव सवर्णसंज्ञा स्यात्, ढकारढकारयोर्भेदात्सवर्णत्वं नास्तीति सवर्णग्रहणमनर्थकं स्यात् ॥

(उद्योतः) भाष्ये—उदात्तादीनां सवर्णसंज्ञा न प्राप्नोतीत्यस्य आस्येन प्रयत्नोऽविशेषित इत्यस्य च समाध्यन्तरमाहैकदेशी—अथवा किं न एतेनेति । नः=अस्माकम्, एतेन=प्रारम्भो यत्नस्येत्यर्थकप्रयत्नशब्दाश्रयणेन किमित्यर्थः । क्लिष्टत्वादिति भावः ॥ बाह्यप्रयत्नभेदेऽपीति । एवमुदात्तादिभेदेऽपि भविष्यतीत्यपि बोध्यम् ॥ यद्यपि सवर्णसंज्ञाया न प्रयत्नभेदगर्भत्वं, तथापि ज्ञापकादेतदर्थसिद्धिरित्याह—झरो झरीति ॥ भाष्ये—सत्येव हि भेदे इति । यत्किञ्चित्प्रयत्नभेदे सत्येवेत्यर्थः ॥ कुत एतदिति । सूत्राक्षरैस्तदलाभ इति प्रश्नः ॥

समाधत्ते—भेदाधिष्ठाना हीति । यत्किञ्चित्प्रयत्नभेदेत्यर्थः ॥ तत्र ज्ञापकमाह—यदि हीति । सवर्णसंज्ञावचनमित्यस्य सवर्णपदोच्चारणमित्यर्थः । संज्ञा तु—अणुदित्सवर्णस्येत्याद्यर्थमावश्यकेति बोध्यम् ॥ भेदादिति । बाह्यप्रयत्नभेदादित्यर्थः ॥ नन्वेवं यत्किञ्चित्स्थानैक्यादेकारौकारयोः सावर्ण्यापत्तिरिति चेन्न । ज्ञापकाश्रयणांशे यावत्प्रयत्नसमानत्वत्यागेऽपि स्थानांशे तत्त्यागे मानाभाव इत्याशयात्, पञ्चम्येकवचनमित्यादिनिर्देशैः स्थानांशे यावत्स्थानतुल्यत्वविवक्षणाच्च ॥

यत्तु तुल्यत्वस्य भेदघटितत्वात्सवर्णसंज्ञा भेदाधिष्ठानेत्यर्थ इति । तन्न । तेन सावर्ण्यनियामकप्रयत्नयोः स्थानयोश्च परस्परभेदलाभेऽपि वर्णानां यत्किञ्चित्प्रयत्नभेदस्य ततोऽलाभात् स्थानानामन्ततस्तत्तत्कालरूपोपाधिभेदेन भेदो बोध्यः ॥

(सिद्धान्तिन आक्षेपभाष्यम्)

यदि तर्हि 'सति भेदे किंचित्समानम्' इतिकृत्वा सवर्णसंज्ञा भविष्यति । शकार-छकारयोः षकार-ठकारयोः सकार-थकारयोः सवर्णसंज्ञा प्राप्नोति । एतेषां हि सर्वमन्यत्समानं करणवर्जम् ॥

(प्रदीपः) सर्वमिति । 'वर्गाणां प्रथमद्वितीयाः' इत्यस्यां शिक्षायां पठितमघोषत्वादि । करणं तु भिन्नं, वर्ग्याणां स्पृष्टत्वादूष्मणां च विवृतत्वात् । सति सवर्णत्वे निश्छत्रं निष्ठुरं निःस्थानं मधुलिट्स्थानमित्यत्र 'झरो झरि' इति लोपः प्राप्नोतीति । छद्मनो निष्क्रान्तमिति प्रादिसमासः । 'अनचि च' इति छकारस्य द्विर्वचनम् ॥

(उद्योतः) भाष्ये—यदि तर्हि सति भेदे-इत्यादि सिद्धान्तिवचः ॥ शकारछकारयोरिति । तस्मात्प्रारम्भो यत्नस्येति आवश्यकमिति भावः ॥ ननु निश्छत्रमित्यत्र हलः परत्वाभावात्कथं लोपप्राप्तिरत आह—अनचि चेति ॥

(एकदेशिसमाधानभाष्यम्)

एवं तर्हि—प्रयतनमेव—प्रयत्नः, तदेव तद्धितान्तमास्यम् । न त्वयं द्वन्द्वः—आस्यं च प्रयत्नश्च आस्यप्रयत्नमिति ।

किं तर्हि ?

त्रिपदोऽयं बहुव्रीहिः—तुल्य आस्ये प्रयत्न एषामिति ॥

(प्रदीपः) तुल्य आस्य इति । तद्धितान्त आस्यशब्दो न स्वाङ्गवाच्येवेति 'अमूर्द्धमस्तकात्' इत्यलुङ् भवति । तद्धितान्तास्यशब्दाश्रयणसामर्थ्यादेव 'आस्ये' इत्येकत्वं विवक्ष्यते । तेनैकस्मिन्नेव स्थाने ययोस्तुल्यः प्रयत्नः-इति आश्रीयते ॥

(उद्योतः) तत्रैकदेशी प्रौढ्या समाधानमाह—एवं तर्हीत्यादि ॥ स्वाङ्गवाच्येवेति । अमूर्धेत्यादिपर्युदासादेव स्वाङ्गे लब्धे स्वाङ्गादिति पुनःश्रुतिरवधारणार्थेति भावः ॥ संज्ञायामित्यनुवृत्तेर्न दोष इत्यन्ये ॥ नन्वेवं भिन्नस्थानानामपि स्यादत आह—तद्धितान्तास्येति । आस्यपदोपादानसामर्थ्याच्च तल्लब्ध इति भावः ॥ एकत्वं विवक्ष्यत इति । तद्विवक्षां विनाऽपि प्रत्यासत्त्या प्रयत्नयोरेकास्यभववृत्तित्वलाभ इत्यन्ये ॥

(भाष्यम्)

अथवा पूर्वस्तत्पुरुषस्ततो बहुव्रीहिः-तुल्य आस्ये-तुल्यास्यः, तुल्यास्यः प्रयत्न एषामिति ॥

(प्रदीपः) अथवेति । मयूरव्यंसकादित्वात्सप्तम्यन्तोत्तरपदस्तत्पुरुषः ॥

(भाष्यम्)

अथवा—परस्तत्पुरुषस्ततो बहुव्रीहिः—आस्ये प्रयत्नः-आस्यप्रयत्नः, तुल्य आस्यप्रयत्नो येषामिति ॥

(उद्योतः) त्रिपदबहुव्रीहौ सप्तम्यन्तस्य पूर्वनिपातापत्तेः पूर्वपदार्थप्रधानतत्पुरुषस्याप्यगतिकगतित्वाद्भाष्ये तृतीय आश्रितः ॥

(इति तुल्यास्यप्रयत्नशब्दार्थनिरूपणम् ॥)

(अथानिष्टसावर्ण्यनिराकरणम्)

(१४० आक्षेपवार्तिकम् ॥ ३ ॥)

॥ * ॥ तस्य ॥ * ॥

(भाष्यम्)

तस्येति तु वक्तव्यम् ।

किं प्रयोजनम् ?

यो यस्य तुल्यास्यप्रयत्नः स तस्य सवर्णसंज्ञो यथा स्यात् । अन्यस्य तुल्यास्यप्रयत्नोऽन्यस्य सवर्णसंज्ञो मा भूत्-इति ॥

(प्रदीपः) तस्येति । यत्तदोर्नित्याभिसंबन्धादाह—यो यस्येति । अन्यथा वर्णान्तरापेक्षया तुल्यास्यप्रयत्नत्वेन सवर्णत्वे तदाश्रयमन्यस्यापि कार्यं प्राप्नोति । सूत्रारम्भस्तु रेफोष्मणां निवृत्त्यर्थः स्यात् ॥

(उद्योतः) रेफोष्मेति । रेफोष्मणां सवर्णा न सन्तीत्युक्तेरिति भावः ॥

(१४१ समाधानवार्तिकम् ॥ ४ ॥)

॥ * ॥ तस्यावचनं वचनप्रामाण्यात् ॥ * ॥

(भाष्यम्)

तस्येति न वक्तव्यम् ।

अन्यस्य तुल्यास्यप्रयत्नोऽन्यस्य सवर्णसंज्ञः कस्मान्न भवति ?

'वचनप्रामाण्यात्' । सवर्णसंज्ञावचनसामर्थ्यात् । यदि हि अन्यस्य तुल्यास्यप्रयत्नोऽन्यस्य सवर्णसंज्ञः स्यात् सवर्णसंज्ञावचनमनर्थकं स्यात् ॥

(प्रदीपः) तस्यावचनमिति । 'तस्य' इत्ययमनुकरणशब्दः, 'तस्य'इत्यस्यावचनमित्यर्थः ॥ सवर्णसंज्ञावचनमिति । न च रेफोष्मणां निवृत्त्यर्थं वचनं, रेफस्यापि रेफः सवर्णो भवत्येव । एवमूष्मस्वपि द्रष्टव्यम् ॥

(उद्योतः) तस्यावचनमिति वार्तिके तच्छब्देन कस्य परामर्शोऽत आह—तस्येत्ययमिति । तस्यावचनमित्यत्र षष्ठीतत्पुरुष इति भावः । एवं च स्यो न विभक्तिरिति लुगभावः ॥ वस्तुतस्तच्छब्देन पूर्वोक्तस्य तस्यशब्दस्य परामर्श इति वक्तुं युक्तम् ॥ रेफस्यापीति । रेफोष्मणामित्येतद् विजातीयसवर्णाभावप्रतिपादनपरमित्यर्थः । तत्र रेफांशे तुल्यास्यप्रयत्नासंभव एव, ऊष्मसु तु नाऽज्झलाविति निषेधादिति बोध्यम् । एवं च व्यावर्त्याभावेन सवर्णसंज्ञावचनसामर्थ्यात् 'यस्य-तस्य' इति लभ्यत इति भावः ॥

(१४२ समाधानवार्तिकम् ॥ ५ ॥)

॥ * ॥ संबन्धिशब्दैर्वा तुल्यम् ॥ * ॥

(भाष्यम्)

संबन्धिशब्दैर्वा पुनस्तुल्यमेतत् । तद्यथा-संबन्धिशब्दाः 'मातरि वर्तितव्यम्' 'पितरि शुश्रूषितव्यम्' इति, न चोच्यते—'स्वस्यां मातरि' 'स्वस्मिन् वा पितरि' इति । संबन्धाचैतद्गम्यते—या यस्य माता, यश्च यस्य पितेति ॥

एवमिहापि-"तुल्यास्यप्रयत्नं सवर्णम्" इत्यत्र संबन्धिशब्दावेतौ, तत्र संबन्धादेतद्गन्तव्यम्—यत्प्रति यत्तुल्यास्यप्रयत्नं तत्प्रति तत्सवर्णसंज्ञं भवतीति ॥

(प्रदीपः) एवं वचनसामर्थ्याद्दोषं परिहृत्य शाब्दन्यायेन परिहर्तुमाह—संबन्धिशब्दैरिति ॥ संबन्धिशब्दाविति । तुल्यास्यप्रयत्नशब्दस्य संबन्धिशब्दत्वात्तत्समानार्थोऽपि प्रदेशवाक्येषूपात्तः सवर्णशब्दः संबन्धिशब्दः । यथा-तुल्याय कन्या दातव्या-इत्युक्ते न शूद्रेण तुल्याय ब्राह्मणः कन्यां ददाति, अपि त्वात्मना । तथेहापीत्यर्थः ॥

(उद्योतः) ननु सवर्ण इति संज्ञाशब्दस्य कथं संबन्धिशब्दत्वमत आह—तुल्यास्येत्यादि । स्वार्थभिन्नप्रतियोगिकसंबन्धनिमित्तशब्दः संबन्धिशब्द इति भावः ॥

परे तु अत्र सूत्रे द्वन्द्वनिर्देशलभ्यौ तुल्यास्यतुल्यप्रयत्नशब्दाविस्यर्थो भाष्यस्य । सवर्णशब्दो हि प्रदेशेऽपि सवर्णपदवत्परः, न तु तुल्यास्यप्रयत्नत्वप्रवृत्तिनिमित्तक इति तस्य संबन्धिशब्दत्वं दुरुपपादम् । उपक्रमोपसंहाराभ्यां चैवमेवोचितम् ॥ उपक्रमे हि तुल्यास्यं च तुल्यप्रयत्नं च सवर्णसंज्ञं भवतीत्युक्तमित्याहुः ॥

(अथ ऋऌवर्णयोः सावर्ण्यम्)

(१४३ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ ऋकारऌकारयोः सवर्णविधिः ॥ * ॥

(भाष्यम्)

ऋकारऌकारयोः सवर्णसंज्ञा विधेया । होतृ-ऌकारः-होतृकारः ।

किं प्रयोजनम् ?

"अकः सवर्णे दीर्घः" इति दीर्घत्वं यथा स्यात् ॥

(प्रदीपः) **ऋकारऌकारयोरिति** । स्थानभेदान्न प्राप्नोतीत्यारम्भः ॥ अत्र चानयोरेव श्रुतत्वान्मिथः सवर्णसंज्ञा विज्ञायते, न त्वेतयोरन्येन सहेति बोद्धव्यम् ॥

(उद्द्योतः) (भाष्ये) **ऋकारऌकारयोरि**त्यत्र ऋत्यक इति प्रकृतिभावः । वार्तिकेऽप्येवमेव पाठ इति प्रामाणिकाः ॥ सावर्ण्यप्रतियोग्यनिर्देशादाह—**अत्र चेति** ॥ भाष्ये–**होतृ ऌकारः-होतृकार इति** । ऌकारशब्दो देवतावाचीत्येके ॥ विवृतस्य ऌकारस्य दीर्घस्याभावादृकारो दीर्घ उदाहृत इति बोध्यम् ॥

(सावर्ण्यखण्डनभाष्यम्)

नैतदस्ति प्रयोजनम् । वक्ष्यत्येतत्—"*सवर्णदीर्घत्वे ऋति ॠ वा वचनम्–" "*ऌति ॡ वा वचनम्*" इति ॥

(प्रदीपः) **वक्ष्यत्येतदिति** । तत्र **'ऌ वा वचनम्'** इत्यत्र दीर्घ इत्यनुवर्तते । तत्र ऌति ऌशब्दे विकल्पितेऽप्राप्त एव पक्षे दीर्घो भविष्यति । स च भवन् ऌवर्णस्य दीर्घाभावाद्वर्णस्यान्तरतमो दीर्घ ॠकारो भविष्यति ॥

(उद्द्योतः) **नैतदस्तीति** । सवर्णसंज्ञाया इति शेषः ॥ नन्वीषत्स्पृष्टेन मुखेऽपि विवृतदीर्घः सवर्णसंज्ञां विना दुर्लभोऽत आह—**तत्रेति** ॥

(सावर्ण्यमण्डनभाष्यम्)

तत्सवर्णे यथा स्यात् । इह मा भूत्-दध्यॢकारः, मध्वॢकार इति ॥

(प्रदीपः) **तत्सवर्ण इति** । यद्यविधाय सवर्णसंज्ञां तदुच्यते, अग्मात्रस्य ऌति तत्कार्यं स्यात्-**दध्लृकार** इति । तस्माद्विधेया सवर्णसंज्ञा ॥

(उद्द्योतः) भाष्ये–तद्वचनद्वयारम्भेऽपि सवर्णसंज्ञाऽऽवश्यकीत्याह—**तत्सवर्ण इति** ॥ **अग्मात्रस्येति** । अनन्व्यावृत्त्यर्थमक इति वर्तते, सवर्णसंज्ञाऽभावात्सवर्ण इति नानुवर्तत इति भावः ॥

(सावर्ण्यखण्डनभाष्यम्)

यदेतत्सवर्णदीर्घत्वे 'ऋति' इति एतत् 'ऋतः' इति वक्ष्यामि । ततः—"ऌति" । ऌकारे वा ॡ भवति, ऋत इत्येव ॥

(प्रदीपः) **ऋत इति वक्ष्यामीति** । ऋकारस्य ऋकार एव सवर्ण इति ऋत्येव भविष्यति । ततः **"ऌति"** । **ऋत** इत्येव । इदं चासवर्णार्थम् । तेन ऌति रूपद्वयं सिद्धम् । तत्रासंहितायामृकारे होतृ ऋकार इति रूपम्, संहितायामपि **'ऋत्यकः'** इति शाकलप्रकृतिभाव एतदेव रूपम् । शाकलाभावे 'होतृकारः' 'होतॄकारः' इति रूपद्वयम् । ऌकारेऽसंहितायां संहितायां वा शाकले होतृऌकार इति रूपम् । शाकलाभावे तु होतॄकारो होत्ऌकार इति रूपद्वयम् ॥

(उद्द्योतः) खण्डयति—**यदेतदिति**–भाष्ये ॥ **सवर्ण इतीति** । आद्यवार्तिके सवर्णसंज्ञाऽनुवर्तत इति भावः ॥ **तेन ऌतीति** । सिद्धान्तेऽपि व्यवस्थितविभाषया–अनभिधानेन **वा** होतृऌकारे पूर्ववार्तिकं गमॢकारे चोत्तरवार्तिकं न प्रवर्तते । एवं कॄ इति दीर्घस्य ऋकारे परे पूर्वस्य, तस्यैव ऌकारे उत्तरस्य चाप्रवृत्तिस्तत एवेति भावः ॥ **रूपद्वयमिति** । ईषत्स्पृष्टघटितं विवृतदीर्घघटितं चेति भावः ॥ **तत्रासंहितायामिति** । समासे संहिता नित्या । असमासे त्वीदृशं रूपं दुर्लभं, होतृशब्दे विभक्तिश्रवणापत्तेः । होतृशब्दस्य नपुंसके संबुद्धौ रूपमित्यप्यतिक्लिष्टमिति **चिन्त्यम्** ॥ भाष्ये तु **होतृऌकार** इति दीर्घप्रवृत्तियोग्यदशोच्चारणम् ॥ **इति**-स्थिते इति शेषः । एवं शाकले होतृऌकार इत्यपि चिन्त्यं, सवर्णत्वविधायकवचनाभावे एतद्विचारसत्त्वेन तत्र ऋत्यक इत्यस्याप्राप्तेः । **इकोऽसवर्ण** इत्यपि 'न समासे' इति निषिद्धम् । नित्यग्रहणं तु तत्र भाष्ये प्रत्याख्यातमित्याहुः ॥

(सावर्ण्यमण्डनभाष्यम्)

तत्र वक्तव्यं भवति ॥

(प्रदीपः) **तत्र वक्तव्यमिति** । द्वावप्येतौ दीर्घौ 'ॠ ॡ' इति । तत्र ऋकारे कदाचित् 'ॠ' इति दीर्घः कदाचित् ॠ । ऌकारेऽपि 'ॠ' 'ॡ' इत्येतौ भविष्यतः सत्यां सवर्णसंज्ञायामिति भावः ॥

(उद्द्योतः) सवर्णसंज्ञावचनेनैकेनैव सिद्धे तद्द्वयं न कार्यमित्याह—भाष्ये—**तत्र वक्तव्यमिति** ॥

(सावर्ण्यखण्डनभाष्यम्)

अवश्यं तद्वक्तव्यम् । ऊकालोऽज्झ्रस्वदीर्घप्लुतसंज्ञो भवतीत्युच्यते । न च 'ॠ'कार 'ॡ'कारो वाऽजस्ति ॥

(प्रदीपः) **न चेति** । अर्धतृतीयमात्रत्वादिति केचिदाहुः । अन्ये तु ईषत्स्पृष्टकरणत्वात्, अनयोर्ॠकारॡकारयोश्च विवृतत्वात्ताभ्यां तयोरग्रहणादनच्त्वमाहुः ॥

(उद्द्योतः) इतर आह—**अवश्यमिति** ॥ **अर्धतृतीयेति** । तावताऽपि स्थानप्रयत्नसाम्येन ताभ्यां ग्रहणं स्यादित्यरुचेराह—ईष-

ईषत्स्पृष्टेति। विवृतत्वाभावे उपस्थितरेफीयप्रयत्नत्यागे मानाभावादिति भावः॥ ताभ्यामिति। असावर्ण्यादिति भावः॥

(सावर्ण्यमण्डनभाष्यम्)

ऋकारस्य ऌकारस्य चाच्त्वं वक्ष्यामि।

तच्चावश्यं वक्तव्यम्, प्लुतो यथा स्यात्। होतृ ऋकारः–होतॄकारः, होतृ३कारः। होतृ ऌकारः–होतॢकारः, होतॢ३कार इति॥

(प्रदीपः) **अच्त्वं वक्ष्यामीति।** सत्यच्त्वे दीर्घसंज्ञाऽनयोर्भविष्यति। येषां तु मतमर्धतृतीयमात्रावेताविति, तेषां मते सत्यप्यच्त्वे द्विमात्रत्वाभावादेतयोर्दीर्घसंज्ञा न प्राप्नोति। तस्मात्रिमात्रावेतावभ्युपगन्तव्यौ॥ **तच्चावश्यमिति।** त्वयाऽपि **'ऋषा वचनं ऌषा वचनं'** इति ब्रुवताऽच्त्वमनयोर्वक्तव्यम्। अन्यथा विधानमात्रमनयोः स्यात्, नाच्कार्यं प्लुतः। सति त्वच्त्वे ताभ्यां त्रिमात्रयोरपि सावर्ण्याद्ग्रहणे सति प्लुतसंज्ञा भविष्यतीति प्लुतसिद्धिः॥

(उद्द्योतः) भाष्ये—वचनद्वयप्रत्याख्यानवाद्याह—ऋकारस्येत्यादि॥ **सत्यच्त्वे इति।** अयोगवाहेषु पाठादिति भावः॥ **नाच्कार्यमिति।** तस्य प्लुतसंज्ञा तत्स्थाने प्लुतश्चेति भावः॥

(आक्षेपभाष्यम्)

किं पुनरत्र ज्यायः?

(प्रदीपः) **किं पुनरिति।** एकैकस्मिन्संहितायां शाकलाभावपक्षे रूपद्वयं साध्यम्। तच्चोभयथाऽपि सिध्यति। तत्र सवर्णसंज्ञायामसत्यां यथा सिध्यति तथा पूर्वमेवोक्तम्। सत्यां तु यथा सिध्यति तथोच्यते—द्वयोर्ऋकारयो रेफद्वययुक्तत्वाद्विवृतत्वाच्च कदाचिद्रेफद्वययुक्त 'ऋ' भवति कदाचिद्विवृत ऋकारः। ऌकारेऽपि कदाचिदृकारान्तरतमः 'ॠकारः' कदाचिद् ऌकारान्तरतम ॡकार इति साम्यमुभयोः पक्षयोः॥

(उद्द्योतः) अत्र पक्षेऽपि उक्तयुक्त्या ह्रस्वऋकारद्वयस्थानिकदीर्घैकादेशातिरिक्तविषये आद्यस्य ह्रस्वऋकारऌकारद्वयस्थानिकदीर्घैकादेशातिरिक्तविषये द्वितीयस्य न साधुत्वमिति नातिप्रसङ्गः पक्षयोस्तुल्यफलता चेति बोध्यम्। तदेव ध्वनयन् पृच्छति–भाष्ये—**किं पुनरत्रेति॥ ऋकार इति।** विवृत इत्यर्थः॥ **ऌकार इति।** ईषत्स्पृष्ट इत्यर्थः॥

(समाधानभाष्यम्)

सवर्णसंज्ञावचनमेव ज्यायः, दीर्घत्वं चैव हि सिद्धं भवति। अपि च ऋकारग्रहणे ऌकारग्रहणं संनिहितं भवति। "ऋत्यकः"–खट्व ऋश्यः; माल ऋश्यः। इदमपि सिद्धं भवति—खट्व ऌकारः, माल ऌकार इति॥ "वा सुप्यापिशलेः"– उपर्कारीयति, उपार्कारीयति। इदमपि सिद्धं भवति—उपल्कारीयति, उपाल्कारीयति॥

(उद्द्योतः) भाष्ये—**दीर्घत्वं चैव हीति।** ईषत्स्पृष्टविवृतरूपो दीर्घो वर्ण इत्यर्थः॥ चं व्याचष्टे—**अपि चेत्यादिना। खट्व ऌकार इति।** होतृऌकार इत्यस्याप्युपलक्षणम्॥

(एकदेशिन आक्षेपभाष्यम्)

यदि तर्हि ऋकारग्रहणे ऌकारग्रहणं संनिहितं भवति, "उरण्रपरः" ऌकारस्यापि रपरत्वं प्राप्नोति॥

(समाधानभाष्यम्)

ऌकारस्य लपरत्वं वक्ष्यामि। तच्चावश्यं वक्तव्यम्। असत्यां सवर्णसंज्ञायां विध्यर्थम्। तदेव सत्यां रेफबाधनार्थं भविष्यति॥

(प्रदीपः) **लपरत्वमिति।** व्याख्यास्यामीत्यर्थः॥ **'रपरः'** इत्यत्र 'र' इति लकाराकारेण प्रत्याहार आश्रीयते। तत्रान्तरतम्यादृकारस्याण् रपरो भवति, ऌकारस्याण् लपर इति॥ **असत्यामिति।** असत्यां सवर्णसंज्ञायां **'उरण् रपरः'** इत्यत्र ऌकारग्रहणं कर्तव्यं भवति॥

(उद्द्योतः) वचनस्य क्वाप्यदर्शनादाह—व्याख्यास्यामीति। अन्ये तु लण्सूत्रस्थाकारस्यानुनासिकत्वेऽसौ लृप्तस्येत्यत्र भगवान्पाणिनिर्लकारं नोच्चारयेत्, प्रत्याहारेणैव निर्वाहात्। तस्मादपूर्वं वचनं कार्यमित्येव भाष्याशय उचित इत्याहुः॥ आन्तरेति। ऋत्वे रपरो ऌत्वे लपर इत्यर्थः॥ सवर्णसंज्ञावादी तदभाववादिनं प्रति तवाप्यावश्यकं तदित्याह—तच्चावश्यमिति। ऌकारस्याण् लपर इत्येतत्॥

(एकदेशिन आक्षेपभाष्यम्)

इह तर्हि—"रषाभ्यां नो णः समानपदे" इत्यृकारग्रहणं चोदितं मातॄणां पितॄणामित्येवमर्थम्। तदिहापि प्राप्नोति—क्लृप्यमानं पश्येति।

(प्रतिबन्दीभाष्यम्)

अथासत्यामपि सवर्णसंज्ञायाम्, इह कस्मान्न भवति—प्रक्लृप्यमानं पश्येति॥

(प्रदीपः) **प्रक्लृप्यमानमिति।** **'कृत्यचः'** इति णत्वप्रसङ्गः॥

(प्रतिबन्दीसमाधानेनाक्षेपनिरासभाष्यम्)

"चुटुतुलशर्व्यवाये न॰" इति वक्ष्यामि॥

अपर आह–"त्रिभिश्च मध्यमैर्वर्गैर्लशसैश्च व्यवाये न" इति वक्ष्यामीति। वर्णैकदेशाश्च वर्णग्रहणेन गृह्यन्त इति योऽसौ ऌकारे लकारस्तदाश्रयः प्रतिषेधो भविष्यति॥

(प्रदीपः) **त्रिभिश्चेति।** पूर्वस्मादयं विशेषः—पूर्वत्र शरन्तर्भूतोऽपि षकारः साक्षाण्णत्वनिमित्तत्वात् व्यवधायकत्वेन नाश्रीयते। इह तु तस्यानुपादानमेव॥ **वर्णैकदेशा इति।** अवयवस्य स्वव्यापारानिवर्तनात्। अग्रहणपक्षे तु क्षुभ्नादेराकृतिगणत्वाण्णत्वाभावः॥

(उद्द्योतः) **साक्षादिति।** रषाभ्यामिति वचनादित्यर्थः॥ नन्वत्र लकाराभाव इत्यत आह—भाष्ये— **वर्णैकदेशा इत्यादि॥** अग्रहणपक्षे त्विति। प्रक्लृप्यमानमित्यत्र क्लृप्यमानमित्यत्र चेति

भावः । आद्ये कृत्यच इति, द्वितीये ऋवर्णान्नस्येति प्राप्तिः ॥

(सिद्धान्तोपसंहारभाष्यम्)

यद्येवं, नार्थो रषाभ्यां णत्वे ऋकारग्रहणेन । वर्णैकदेशाश्च वर्णग्रहणेन गृह्यन्त इति योऽसौ ऋकारे रेफः, तदाश्रयं णत्वं भविष्यति ॥

(प्रदीपः) ऋदितां लृदितां च भेदेनानुबन्धनिर्देशात् भेदेन चोपादानादनुबन्धकार्येषु परस्परग्रहणाभावात्संकराभावः ॥ ९ ॥

(उद्योतः) भेदेनेति । ओणृ गम्लृ इति भेदेनानुबन्धनिर्देशः । 'नाग्लोपिशास्वृदितां' 'पुषादिद्युताद्य्लृदितः' इति च भेदेनोपादानमित्यर्थः ॥ ९ ॥

(९ संज्ञानिषेधसूत्रं ॥ परिभाषासूत्रं वा ॥ १।१।४आ. ७ ॥)

नाज्झलौ ॥ १ । १ । १० ॥

(शकारसावर्ण्यनिषेधनिराकरणम्)

(१४४ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ अज्झलोः प्रतिषेधे शकारप्रतिषेधोऽज्झल्त्वात् ॥ * ॥

(भाष्यम्)

अज्झलोः प्रतिषेधे शकारस्य शकारेण सवर्णसंज्ञायाः प्रतिषेधः प्राप्नोति ।

किं कारणम् ?

अज्झल्त्वात् । अच्चैव हि शकारो हल्च ।

कथं तावदच्त्वम् ?

इकारः सवर्णग्रहणेन शकारमपि गृह्णातीत्येवमच्त्वम् ।

हल्षु चोपदेशाद्धल्त्वम् ॥

(प्रदीपः) नाज्झलौ ॥ १० ॥ अकारहकारयोरिकारशकारयोश्च तुल्यस्थानप्रयत्नत्वात्सवर्णसंज्ञा प्राप्ता निषिध्यते । अत एव च निर्देशादचामज्भिर्हलां हल्भिः सवर्णत्वानिषेधः ॥ अज्झलोरिति । प्रकृतत्वात् सवर्णसंज्ञाया इति बोद्धव्यम् ॥ शाकारप्रतिषेध इति । द्विवचनान्तस्य समासः, भेदाधिष्ठानत्वात्सवर्णसंज्ञायाः ॥ इकार इति । अत्र हि सूत्रे 'अच्' इतीकारो गृह्यमाणः सवर्ण गृह्णातीति शकारस्यापि ग्रहणमस्ति । स्वात्मनि क्रियाविरोधादस्मिन्नेव सूत्र इदं न व्याप्रियत इति सवर्णत्वनिषेध इकारशकारयोर्नास्ति । 'यस्येति च' इत्यादौ तु शकार इकारेण न गृह्यते, अनेन सवर्णत्वनिषेधात् । इह तु स्वात्मनि व्यापारो नास्ति, अस्ति च पूर्वेण सवर्णत्वमिकारशकारयोरिति भावः । प्रकल्प्य चापवादविषयमिति न्यायोऽत्र नास्ति, अपवादस्यैवासंपत्त्या ॥

(उद्योतः) नाज्झलौ ॥ १० ॥ अकारेत्यादि । एवंच हरिरित्यादौ दीर्घः, शयनमित्यादौ यण प्राप्तिरिति भावः ॥ अत एवेति । पूर्वसवर्णदीर्घनिर्देशादित्यर्थः । किं चैवं सति 'अकः सवर्णे' इति 'झरो झरि सवर्णे' इत्यस्यासङ्गतिरित्यपि बोध्यम् ॥ भेदाधिष्ठानत्वादिति । व्यक्त्यैक्ये हि तुल्यास्यप्रयत्नत्वासंभव इति भावः ॥ सवर्णग्रहणेनेति—भाष्ये । सवर्णग्राहकेणाणुदित्सूत्रेणेत्यर्थः ॥ अत्र हि सूत्रे इति । उच्चारितस्यैव प्रत्यायकतामत्रत्यपूर्वपक्षी न जानाति, प्रत्याहारेषु जातिग्रहणमिति च न जानाति ॥ ननु सति सवर्णत्वे इकारः शकारं गृह्णीयात् । तदेव च न, नाज्झलाविति निषेधादत आह—स्वात्मनीति । यद्यपि स्वाध्यायोऽध्येतव्य इत्यात्मानमपि विषयीकरोतीति एकस्य विषयत्वविषयित्वयोर्न विरोधस्तथाप्येतद्वाक्यार्थबोधोत्तरमन्यत्र निषेधेऽपि स्ववाक्यार्थबोधात्प्राक् स्वघटकपदार्थोपस्थितिवेलायां स्ववाक्यार्थबोधरूपसावर्ण्याभावज्ञानाभावान्नेकारशकारयोस्तदभावबोधनमिति भावः ॥ अपवादस्यैवासंपत्त्येति । अपवादस्य नाज्झलावित्यस्यासंपत्त्या प्राग्बोधाभावेन स्वविषयेऽप्राप्त्यैतद्घटकपदोपस्थितयोरिकारशकारयोर्नापवादविषयत्वमित्यर्थः ॥

(वार्तिकांशावतरणभाष्यम्)

तत्र को दोषः ?

(१४५ आक्षेपसाधकवार्तिकम् ॥ २ ॥)

॥ * ॥ तत्र सवर्णलोपे दोषः ॥ * ॥

(भाष्यम्)

तत्र सवर्णलोपे दोषो भवति । परश्शतानि कार्याणि—"झरो झरि सवर्णे" इति लोपो न प्राप्नोति ॥

(प्रदीपः) परश्शतानीति । शतात्पराणि शताधिकानीत्यर्थः । 'कर्तृकरणे कृता बहुलम्' इति बहुलवचनात्समासः । पारस्करादित्वात्सुडागमः, सकारस्य श्चुत्वम्, 'अनचि च' इति द्विर्वचनम् । 'झरो झरि' इति लोपाप्रसङ्गात् त्रिशकारकश्रवणप्रसङ्गः । 'शरोऽचि-अनचि च' इत्यत्र इकारेण शकारो न गृह्यते, अनेन सवर्णत्वनिषेधात्—इत्यस्ति शकारस्य द्विर्वचनम् ॥

(उद्योतः) बहुलेति । मयूरव्यंसकादित्वात्सुप्सुपेति वा समास इत्युचितम् ॥ ननु कथं शस्य द्वित्वम्, अचि नेति शरोऽचीति वा निषेधापत्तेरत आह—शरोऽचीति ॥

(१४६ समाधानवार्तिकम् ॥ ३ ॥)

॥ * ॥ सिद्धमनच्त्वात् ॥ * ॥

(भाष्यम्)

सिद्धमेतत् ।

कथम् ?

अनच्त्वात् ।

कथमनच्त्वम् ?

"स्पृष्टं स्पर्शानां करणं" । "ईषत्स्पृष्टमन्तस्थानाम्" । "विवृतमूष्मणाम्" ईषदित्यनुवर्तते ॥ "स्वराणां च" विवृतम्, ईषदिति निवृत्तम् ॥

(प्रदीपः) **सिद्धमनच्त्वादिति** । सूत्रप्रत्याख्यानसाधारणमुक्तम् । प्रयत्नभेदादज्झलोः सवर्णसंज्ञायाः प्राप्तिरेव नास्तीत्यर्थः ॥

(उद्योतः) ननु प्रयत्नभेदेनानच्त्वे सूत्रमेव व्यर्थं स्यादत आह—**सूत्रेति** ॥ भाष्ये-ईषदित्येति । एङैचोः परस्परसावर्ण्याभावाय विवृततरव्याख्यानामपि सवर्णसंज्ञानियामकत्वस्य सूत्रमतेऽप्यावश्यकत्वेन तदाश्रित्य सूत्रानारम्भ एव ज्यायान् । किंच दीर्घप्लुताकारहकारयोः सावर्ण्यव्यावृत्तये इदमपि तस्यावश्यकमिति भावः ॥

(१४७ समाधानान्तरवार्तिकम् ॥ ४ ॥)

॥ * ॥ वाक्यापरिसमाप्तेर्वा ॥ * ॥

(भाष्यम्)

वाक्यापरिसमाप्तेर्वा पुनः सिद्धमेतत् ॥

किमिदं वाक्यापरिसमाप्तेरिति ? ।

वर्णानामुपदेशस्तावद् । उपदेशोत्तरकालेत्संज्ञा । इत्संज्ञोत्तरकाल "आदिरन्त्येन सहेता" इतिप्रत्याहारः । प्रत्याहारोत्तरकाला सवर्णसंज्ञा । सवर्णसंज्ञोत्तरकालम् "अणुदित्सवर्णस्य चाप्रत्ययः" इति सवर्णग्रहणम् । एतेन सर्वेण समुदितेन वाक्येनान्यत्र सवर्णानां ग्रहणं भवति । न चात्रेकारः शकारं गृह्णाति ॥

(प्रदीपः) **वाक्येति** । भवतु वा तुल्यास्यप्रयत्नत्व तथापीहेकारेण शकारो न गृह्यते सवर्णसंज्ञाया अस्मिन्सूत्रेऽनिष्पादात् । अस्मिन् हि सूत्रे निष्पन्ने सत्यपवादविषयपरिहारेणेष्टे विषये सवर्णसंज्ञा प्रवर्तते । न त्वेतत्सूत्रनिष्पत्त्यवस्थायाम् । ततश्चाक्षेषूपदेशेत्संज्ञाप्रत्याहारसवर्णत्वेषु निष्पन्नेष्वणुदित्सवर्णस्येत्येतदस्य च्वावित्यादौ प्रवर्तते न त्वक्षेषूपदेशादिषु, नापि स्वात्मनि । ततश्चात्र सूत्रेऽज्ञानिष्पत्त्याणुदिदित्यस्याप्रवर्तनादिकारेण शकारस्याग्रहणात्सवर्णत्वं शकारयोः सिद्धम् । एवमीकारोऽप्यत्रेकारेण न गृह्यत इतीकारशकारयोः सवर्णत्वमस्तीति कुमारी शेते इत्यत्र सवर्णदीर्घत्वं प्राप्तमचीत्यनुवृत्त्या निवार्यते ॥

(उद्योतः) **वाक्यापरिसमाप्तेर्वेति** । अन्यथा नाज्झलावित्यस्य निषेधस्य स्वस्मिन्नपि प्रवृत्तौ तव पूर्वपक्षस्यैवानुत्थानं स्यादिति भावः ॥ अनिष्पादमुपपादयति—**अस्मिन्हीति** ॥ **सूत्रे निष्पन्ने इति** । जनितवाक्यार्थबोधे इत्यर्थः ॥ **प्रवर्तते इति** । ' एते परस्परं सवर्णसंज्ञाः' इति प्रमारूपं निश्चयज्ञानं निष्पद्यत इत्यर्थः । तदेव च लक्ष्यसंस्कारकमिति भावः ॥ **निष्पत्त्यवस्थायाम्**—वाक्यार्थबोधावस्थायाम् ॥ **सवर्णत्वेषु निष्पन्नेषु** । तत्र सवर्णत्वनिष्पत्तिरिष्टविषये सवर्णपदवाच्यत्वग्रहः ॥ **नापि स्वात्मनीति** । अनिष्पत्तेरिति भावः ॥ **अज्ञानिष्पत्त्या**—अज्ञस्य=इष्टविषयसवर्णपदवाच्यत्वज्ञानस्यानिष्पत्त्या ॥ भाष्ये—तावत्=प्रथमम् ॥ **उपदेशोत्तरकालेति** । ज्ञातस्य संज्ञाविधानादिति भावः ॥ **प्रत्याहारोत्तरकाला** सवर्णसंज्ञेत्यादेः-इष्टविषये सवर्णसंज्ञासंज्ञित्वग्रहणम्, तदुत्तरकालमणुदिदित्येतदकारादिभिः स्वसवर्णत्वेन ज्ञातानां ग्रहणं बोधयतीत्यर्थः ॥ **अपरिसमाप्तिश्च** सवर्णनिर्णयं 'विना' तद्ग्रहणबोधनासामर्थ्यमित्यर्थः । तज्जन्ये शक्तिग्रहे बाधकसंभावनाहिताप्रामाण्यसंभावनासत्त्वादिति तात्पर्यम् ।

येषु **नाज्झलावित्यतः** प्राक् तुल्यास्येत्यस्य बोधाभावेन सवर्णपदार्थज्ञानाभावात् **अणुदिदित्यस्य** वाक्यार्थावबोध इत्यर्थं इति । तन्न । अभावज्ञाने प्रतियोगिज्ञानस्य कारणतया तुल्यास्येत्यतः प्राङ् निषेधवाक्यार्थाभावः, न तु विपरीतमित्यदोषादिति दिक् ॥

सिद्धमिति । अत्रत्याच्पदार्थोपस्थितिकाले वाक्यार्थबोधरूपसावर्ण्याभावज्ञानाभावादिकारशकारयोः सवर्णत्वज्ञानेऽप्यणुदित्सूत्रजन्येष्टविषये वाक्यार्थबोधरूपशक्तिग्रहस्याभावादिकारेणात्र शकारग्रहणमिति भावः ॥ ननु वाक्यापरिसमाप्तिन्यायस्यास्मदादीन्प्रति प्रवृत्तत्वेऽपि पाणिनेस्तत्त्च्छास्त्रप्रणयनान्यथाऽनुपपत्त्या तत्तद्विषयज्ञानस्य प्रागपि सत्त्वावश्यकत्वेन तज्ज्ञानस्यैतच्छास्त्रासाध्यत्वेन च नाज्झलावित्यादौ सवर्णाभिप्रायेण प्रयोगः स्यात् । अस्मदादीनां बोधस्तु तत्तात्पर्यग्राह्यायात्परंपरया लक्षणया भविष्यतीति शकारयोः प्रतिषेधः प्राप्नोति । एवमकारहकारयोरपीति चेन्न । ज्ञानसत्त्वेऽपि तदभिप्रायेण प्रयोगे तात्पर्यग्राहकाभावात् । करिष्यमाणसंज्ञाद्यभिप्रायेण पाणिनिव्यवहाराभावस्यैव प्रतिपादनाच्च । अत एव हलन्त्यसूत्रे इतरेतराश्रयव्यवहाराभावस्यैव प्रतिपादनाच्च । अन्यथा पाणिनिना हलपदार्थस्य मात्रकृत्य एकशेषेण समाहितं भाष्ये । अन्यथा पाणिनिना हलपदार्थस्य ज्ञातत्वेन तस्यान्योन्याश्रयाभावात्तेन तदभिप्रायेण प्रयोगे बोद्धृबोधस्य लक्षणयैवोपपत्तौ तत्पर्यन्तधावनमनर्थकं स्यात् । मम तु पाणिनेस्तथा व्यवहाराभावान्न दोषः ॥ उक्तार्थे ज्ञापकमप्युपन्यस्यति—**एवमीकारोऽपीति** । अत्र पक्षे दीर्घप्लुताकाराभ्यां हकारे सावर्ण्यवारणं तु प्रक्षेपाद्बोध्यम् । तत्र तात्पर्यग्राहका चेलावित्यादिनिर्देशाः प्रागुक्तं भाष्यं च-इति बोध्यम् ॥

(आक्षेपभाष्यम्)

यथैव तर्हीकारः शकारं न गृह्णाति, एवमीकारमपि न गृह्णीयात् ।

तत्र को दोषः ?

कुमारी-ईहते-कुमारीहते, अकः सवर्णे दीर्घत्वं न प्राप्नोति ॥

(प्रदीपः) तत्र क्व ग्रहणकशास्त्रं प्रवर्तते क्व नेति विषयविभागदर्शनाय चोद्यं करोति—**यथैव तर्हीति** । इकारस्य यत्नाग्राहकत्वं दृष्टमिति **'अकः सवर्णे दीर्घः'** इत्यत्रापि प्राप्तमिति **प्रश्नः** ॥

(उद्योतः) प्रदर्शनाय-बोधनाय ॥

(समाधानभाष्यम्)

नैष दोषः । यदेतत् "अकः सवर्णे दीर्घः" इति प्रत्याहारग्रहणं, तत्रेकार ईकारं गृह्णाति, शकारं न गृह्णाति ॥

(उद्योतः) भाष्ये–यदेतदिति । तद्वोधवेलायां वाक्यपरिसमाप्तेरिति भावः ॥

(व्याख्यान्तरभाष्यम्)

अपर आह—

'*अज्झलोः प्रतिषेधे शकारप्रतिषेधोऽज्झल्त्वात्* ।

अज्झलोः प्रतिषेधे शकारस्य शकारेण सवर्णसंज्ञायाः प्रतिषेधः प्राप्नोति ।

किं कारणम् ?

अज्झल्त्वात् । अचैव हि शकारो हल्च ।

कथं तावदच्त्वम् ?

इकारः सवर्णग्रहणेन शकारमपि गृह्णातीत्येवमच्त्वम्, हल्सु चोपदेशाद्धल्त्वम् ॥

तत्र को दोषः ?

तत्र सवर्णलोपे दोषः ।

तत्र सवर्णलोपे दोषो भवति । परश्शतानि कार्याणि । "झरो झरि सवर्णे" इति लोपो न प्राप्नोति, इति ॥

सिद्धमनच्त्वात् ।

सिद्धमेतत् ।

कथम् ?

अनच्त्वात् ।

कथमनच्त्वम्?

वाक्यापरिसमाप्तेर्वा । उक्ता वाक्यापरिसमाप्तिः ॥

(प्रदीपः) अनच्त्वमेव वाक्यापरिसमाप्त्या साध्यते, न तु प्रयत्नभेदेनेत्याह—अपर आहेति ॥

(आक्षेपभाष्यम्)

अस्मिन्पक्षे—'वा' इत्येतदसमर्थितं भवति ॥

(प्रदीपः) अस्मिन्पक्ष इति । एकत्र हि साध्ये हेतुविकल्पो भवति, इह तु साध्यभेदः । सिद्धेरनच्त्वं हेतुः, अनच्त्वस्य वाक्यापरिसमाप्तिः ॥

(उद्योतः) एकत्रेति । तुल्यार्थानां विकल्प इति न्यायादित्यर्थः ॥

(समाधानभाष्यम्)

एतच्च समर्थितम् ।

कथम् ?

अस्तु वा शकारस्य शकारेण सवर्णसंज्ञा, मा वा भूत् ॥

(प्रदीपः) एतच्चेति । 'अस्तु वा ग्रहणमिकारेण शकारस्य' इति वाक्यशेषाध्याहारात् । प्रतिज्ञाविकल्पार्थो वाशब्द इत्यर्थः ॥

(उद्योतः) मा वा भूदित्येतत्सूचितप्रतिज्ञाया आशयमाह–अस्तु वेति ॥

(आक्षेपस्मारणभाष्यम्)

ननु चोक्तम्-परश्शतानि कार्याणि, "झरो झरि सवर्णे" इति लोपो न प्राप्नोति ॥

(आक्षेपबाधकभाष्यम्)

मा भूल्लोपः ॥

(आक्षेपसाधकभाष्यम्)

ननु च भेदो भवति—सति लोपे द्विशकारम्, असति लोपे त्रिशकारम् ॥

(प्रदीपः) ननु चेति । श्रुतिकृतं भेदमुपगम्योच्यते ॥

(उद्योतः) ननु 'व्यञ्जनपरस्यैकस्यानेकस्य वा नोच्चारणे विशेषः' इति न्यायात् कथं भेद इत्यत आह—श्रुतिकृतमिति ॥

(आक्षेपबाधकभाष्यम्)

नास्ति भेदः, असत्यपि लोपे द्विशकारमेव ।

कथम् ?

विभाषा द्विर्वचनम् ॥

(उद्योतः) भाष्ये—असति लोपे त्रिशकारमिति वदन् प्रष्टव्यः–किं द्विशकारं न स्यादिति तवाशयः, उत त्रिशकारं स्यादिति । आद्ये आह—असत्यपीति । द्विशकारं भवत्येवेत्यर्थः ॥

(आक्षेपसाधकभाष्यम्)

एवमपि भेदः, असति लोपे कदाचिद्द्विशकारम्, कदाचित् त्रिशकारम् । सति लोपे द्विशकारमेव ॥

(उद्योतः) द्वितीये आह—एवमपीति । विभाषा द्विर्वचनेऽपीत्यर्थः ॥

(तटस्थाक्षेपभाष्यम्)

स एष कथं भेदो न ?

(प्रदीपः) 'स एष कथं भेदो न' इत्यत्रैव च्छेदः । भेद एवेत्यर्थः ॥

(उद्योतः) एवमपीत्यनेन भेद···एवेत्युक्त्वा तदुपपादनावसरे यदि लोपो न स्यादिति वाच्यम्, किमुच्यते 'नित्यो लोपः स्यात्' इति । अतश्छित्त्वा भिन्नकर्तृकत्वेन योजयति—स एष इति । त्रिशकारमिष्टमेवेति तात्पर्यम् ॥

(तटस्थाक्षेपनिरासभाष्यम्)

स्यात्, यदि नित्यो लोपः स्यात् । विभाषा तु स लोपः ॥

(प्रदीपः) इतर आह—'स्याद्भेदो यदि नित्यो लोपः स्यात् विभाषा तु स लोपः' इति ततो नास्ति भेद इत्यर्थः ॥

(समाधानभाष्यम्)

यथाऽभेदस्तथाऽस्तु ॥ १० ॥

इति श्रीमद्भगवत्पतञ्जलिविरचिते व्याकरणमहाभाष्ये प्रथमस्याध्यायस्य प्रथमे पादे चतुर्थमाह्निकम् ॥

(प्रदीपः) द्विर्वचनमपि विभाषा, 'यरोनुनासिकेऽनुनासिको

वा' इत्यतो वेत्यनुवर्तनात् । लोपोऽपि विभाषा, 'अयो होऽन्यतरस्याम्' इत्यतोऽन्यतरस्यामित्यनुवर्तनादित्यर्थः ॥ १० ॥

इत्युपाध्यायजैयटपुत्रकैयटकृते महाभाष्यप्रदीपे प्रथमस्याध्यायस्य प्रथमे पादे चतुर्थमाह्निकम् ॥

(उद्द्योतः) अयो ह इति । इदं वृत्तिरीत्या । भाष्यरीत्या तु वाऽवसान इत्यत इति बोध्यम् ॥ १० ॥

इति श्रीशिवभट्टसुतसतीगर्भजनागोजीभट्टकृते भाष्यप्रदीपोद्द्योते प्रथमाध्यायस्य प्रथमे पादे चतुर्थमाह्निकम् ॥

अथ पञ्चमाह्निकम् ।

(अथ प्रगृह्यसंज्ञाप्रकरणम्)

(१० प्रगृह्यसंज्ञासूत्रम् ॥ १ । १ । ५ आ. १ सू. ॥)

ईदूदेद्द्विवचनं प्रगृह्यम् ॥ १ । १ । ११ ॥

(अथ तपरपाठप्रयोजनाधिकरणम्)

(आक्षेपभाष्यम्)

किमर्थमीदादीनां तपराणां प्रगृह्यसंज्ञोच्यते ?

(प्रदीपः) **ईदूदेद्द्विवचनं प्रगृह्यम्** ॥ ११ ॥ **किमर्थमिति** । ईदूतोरनण्त्वाद्भिन्नकालनिवृत्त्यर्थं नोपपद्यते तपरत्वम् । उदात्तादीनामभेदकत्वाद्गुणान्तरयुक्तानां सवर्णानां ग्रहणार्थमपि नोपपद्यते । जातिपक्षेऽपि दीर्घोच्चारणात्प्रयत्नाधिक्यात् ह्रस्वानां न भविष्यति, प्लुतानां चेष्यत एव-इतीष्टव्याघातं प्रत्युत तपरत्वं करोतीति **प्रश्नः** ॥

(उद्द्योतः) ईदूदेत् ॥ ११ ॥ व्यक्तिपक्षे ईदूतोस्तपरयोरुपादानं भिन्नकालनिवृत्तये वा-गुणान्तरयुक्तग्रहणाय वा स्यात् । तत्र नाद्य इत्याह—**ईदूतोरिति** । एवं चाणुदित्त्वस्य प्राप्त्यभावात्तद्बाधकतपरसूत्रप्रवृत्त्यै तपरत्वमित्यर्थः ॥ तपरसूत्रेऽण्ग्रहणाननुवृत्त्या तस्य प्राप्तावपि फलाभावात् न **द्वितीय** इत्याह—**उदात्तादीनामिति** ॥ ननु जातिपक्षे भिन्नकालनिवृत्त्यर्थं स्यात्, तत्पक्षे हि तपरसूत्रं नियमार्थमेवेत्यत आह—**जातीति** ॥ **प्लुतानां चेष्यत एवेति** । एतच्च भाष्ये एव स्फुटम् ॥ **इष्टव्याघातमिति** । जातिपक्षे ईदूदंशेऽपि तपरत्वेनैव प्लुतव्यावृत्तिरित्यभिमानः ॥

(समाधानभाष्यम्)

"तपरस्तत्कालस्य" इति तत्कालानां सवर्णानां ग्रहणं यथा स्यात् ।

केषाम् ?

उदात्तानुदात्तस्वरितानाम् ॥

(प्रदीपः) **तपर इति** । व्यक्तिपक्षो भेदकाश्च गुणा इति भावः ॥ **केषामिति** । प्लुतानामग्रहणप्रसङ्गात्प्रश्नः ॥ **उदात्तेति** । क्वचिदनुनासिकग्रहणमप्यस्ति, तत् गुणप्रसङ्गेनोच्चारितम् । न हि प्रगृह्योऽनुनासिकः सम्भवति, **"अणोऽप्रगृह्यस्यानुनासिकः"** इति निषेधात् ॥

(उद्द्योतः) भेदकाश्च गुणा इति । भेदकत्वात्स्वरस्येति वार्तिकोक्तेरणुविषये भेदकपक्षोऽप्यस्तीत्यभिमानः ॥ इदं प्रयोजनमीदूतोरेव न त्वेदंशे, अणुदित्सूत्रेणैव सिद्धेः ॥

(आक्षेपभाष्यम्)

अस्ति प्रयोजनमेतत् ।

किं तर्हीति ?

प्लुतानां तु प्रगृह्यसंज्ञा न प्राप्नोति ।

किं कारणम् ?

अतत्कालत्वात् । न हि प्लुतास्तत्कालाः ॥

(प्रदीपः) **प्लुतानां त्विति** । व्यक्तिपक्षाश्रयणादयं दोषः, न तु तपरत्वात् ।

(उद्द्योतः) ननु तत्कालसवर्णसंग्रहार्थं तपरत्वमुक्तं नातत्कालव्यावृत्त्यर्थं, तत्कुतः प्लुतानां न प्राप्नोतीत्यत आह—**व्यक्तिपक्षेति** । ईदूदंशे इदम्, एदंशे तु तपरत्वादेव दोष इति बोध्यम् ॥

(आक्षेपबाधकभाष्यम्)

असिद्धः प्लुतः, तस्यासिद्धत्वात्तत्काला एव भवन्ति ॥

(प्रदीपः) **असिद्ध इति** । शास्त्रासिद्धत्वाश्रयणात् प्लुतबुद्ध्यवसत्यां प्रगृह्यत्वे विधीयमाने द्विमात्रविषया बुद्धिः प्रवर्तते । तथा हि वक्ष्यति—***असिद्धत्ववचनमुत्सर्गलक्षणभावार्थमादेशलक्षणप्रतिषेधार्थं च*** इति ॥

(उद्द्योतः) ननु इतिशब्दादिसमभिव्याहारे कार्यार्थं प्रगृह्यसंज्ञाप्रवृत्तेरन्तरङ्गत्वात्पूर्वं प्लुते तेन स्थानिनो निवृत्तत्वेन प्लुतासिद्धत्वेऽपि कथं स्थान्याश्रया प्रगृह्यसंज्ञेत्यत आह—**शास्त्रेति** । प्रवृत्तेऽपि शास्त्रेऽसिद्धत्वेन तत्प्रवृत्तिबुद्ध्यभावेन प्लुतबुद्ध्यभावाद्द्विमात्रविषयाया बुद्धेस्त्रिमात्रे सत्त्वाद् द्विमात्रबुद्ध्या त्रिमात्रस्य संज्ञेत्यर्थः ॥ एतेन शास्त्रासिद्धत्वाच्छास्त्राप्रवृत्तौ स्थानिनः प्रगृह्यत्वेऽपि पुनः प्लुते तस्य तन्न स्यात् । न च स्थानिवत्त्वम्, अनल्विधाविति निषेधात् । प्लुतस्यान्यत्वस्थित्विधर्मत्वात् ॥ एवं चागच्छतमग्नी३ इत्यादावणोऽप्रगृह्यस्येत्यनुनासिकः स्यादित्यपास्तम् ॥ ननु प्राधान्यात्कार्यासिद्धत्वमेव स्यादत आह—**तथाहीति** ॥ उत्सर्गः=स्थानी ॥

(आक्षेपसाधकभाष्यम्)

सिद्धः प्लुतः स्वरसन्धिषु ।

कथं ज्ञायते—'सिद्धः प्लुतः स्वरसंधिषु' इति ?

यदयं "प्लुतः प्रकृत्या" इति प्लुतस्य प्रकृतिभावं शास्ति ।

कथं कृत्वा ज्ञापकम् ?

सतो हि कार्यिणः कार्येण भवितव्यम् ॥

(प्रदीपः) **यदयमिति** । असिद्धत्वे 'प्लुतः प्रकृत्या' इत्येवमाश्रयणायोगात् कार्यित्वेनाश्रयणादसिद्धत्वाभावोऽनुमीयते । सामान्येन स्वरसन्धिप्रकरणविषयं सिद्धत्वं ज्ञाप्यते, न तु प्रकृतिभाव एव । यथा रोत्वे । एवं सोत्सर्गं सापवादं च प्रकरणमिति

प्रकृतिभावेऽपि प्रगृह्यत्वहेतुके सिद्धत्वमुच्यते ॥

(उद्योतः) सामान्येनेति। तदुत्सर्गेऽपीत्यर्थः ॥ ननु प्रकृतिभावो न स्वरसन्धिप्रकरणस्थस्तत्राह—सोत्सर्गमिति । तदुत्सर्गनिरूपितापवादत्वस्यात्रापि सत्त्वेनेदमपि तत्प्रकरणस्थमेवेति भावः ॥ प्रगृह्यत्वहेतुके प्रकृतिभावेऽपीत्यन्वयः ॥

(प्रयोजनजिज्ञासाभाष्यम्)

किमेतस्य ज्ञापने प्रयोजनम् ?

(प्रदीपः) **किमेतस्येति** । प्रकृतिभाव एवाश्रयात्सिद्धत्वमस्त्विति **प्रश्नः** ॥

(प्रयोजनभाष्यम्)

'अप्लुतादप्लुते' इत्येतन्न वक्तव्यं भवति ॥

(प्रदीपः) इतरो लाघवं दर्शयति—**अप्लुतादिति** । सिद्धं हि प्लुते 'अतः-अति'-इति तपरत्वादेवोत्त्वाप्रसङ्गः ॥

(उद्योतः) **प्रकृतिभाव एवेति** । प्लुतप्रकृतिभाव इत्यर्थः ॥ भाष्ये—एतस्येत्यस्य स्वरसन्धिप्रकरणविषयत्वेन ज्ञापनस्येत्यर्थः ॥

(आक्षेपबाधकभाष्यम्)

किमतो यत्सिद्धः प्लुतः स्वरसन्धिषु । संज्ञाविधावसिद्धः । तस्यासिद्धत्वात्तत्काला एव भवन्ति ॥

(प्रदीपः) **किमत इति** । यथोद्देशे संज्ञापरिभाषे, प्रगृह्यसंज्ञा स्वरसन्धिप्रकरणमध्यपतिता न भवतीति **प्रश्नः** ॥

(आक्षेपसाधकभाष्यम्)

संज्ञाविधौ च सिद्धः ।

कथम् ?

कार्यकालं हि संज्ञापरिभाषम्, यत्र कार्यं तत्रोपस्थितं द्रष्टव्यम्, "प्रगृह्यः प्रकृत्या" इत्युपस्थितमिदं भवति—"ईदूदेद्द्विवचनं प्रगृह्यम्" इति ॥

(प्रदीपः) **कार्यकालमिति** । कार्यार्थत्वाद्गुणानां कार्यस्य च प्रधानत्वात् प्रधानदेशत्वस्य न्याय्यत्वादित्यर्थः ॥

(उद्योतः) **कार्यार्थत्वादिति** । तदेकवाक्यतापन्नं संज्ञासूत्रं तत्प्रकरणस्थमिति भावः ॥

(प्रत्याक्षेपभाष्यम्)

किं पुनः प्लुतस्य प्रगृह्यसंज्ञावचने प्रयोजनम् ?

(समाधानभाष्यम्)

प्रगृह्याश्रयः प्रकृतिभावो यथा स्यात् ॥

(प्रत्याक्षेपबाधकभाष्यम्)

मा भूदेवम् । प्लुतः प्रकृत्या-इत्येवं भविष्यति ॥

(प्रत्याक्षेपसाधकभाष्यम्)

नैवं शक्यम्, उपस्थिते हि दोषः स्यात् । "अप्लुतवदुपस्थिते" इत्यत्र पठिष्यति ह्याचार्यः—*वद्वचनं प्लुतकार्यप्रतिषेधार्थम् । प्लुतप्रतिषेधे हि प्रगृह्यप्लुतप्रतिषेधप्रसङ्गोऽन्येन विहितत्वात्* इति ।

तस्मात्प्लुतस्य प्रगृह्यसंज्ञैषितव्या । प्रगृह्याश्रयः प्रकृतिभावो यथा स्यात् ॥

(प्रदीपः) **उपस्थिते हीति** । उपस्थितः—अनार्ष इतिकरणः । 'अग्नी इति' इत्यत्र प्लुताश्रये प्रकृतिभावे प्रतिषिद्धे प्रगृह्याश्रयः प्रकृतिभाव इष्यते । तदाह-**पठिष्यतीति** । यत्र प्रगृह्यसंज्ञा नास्ति स प्लुताश्रयप्रकृतिभावप्रतिषेधविषयः—देवदत्ता३ इति, देवदत्तेति ॥

(उद्योतः) **प्रतिषिद्धे इति** । अप्लुतवद्भावेन बाधिते इत्यर्थः ॥ भाष्ये—**प्रगृह्यप्लुतप्रतिषेधेति** । प्रगृह्याश्रये प्रकृतिभावे प्लुतप्रतिषेधप्रसङ्ग इत्यर्थः ॥ प्रगृह्याश्रयस्यापि कुतो न निवृत्तिरित्यत आह—**अन्येनेति** । 'प्रगृह्यः प्रकृत्या' इत्यनेनेत्यर्थः ॥ नन्वीदृशेऽपि विषये प्रगृह्याश्रयप्रकृतिभावे सति प्लुताश्रयप्रकृतिभावप्रतिषेधोऽप्लुतवदिति बोधितो व्यर्थ इत्यत आह—**यत्रेति** ॥

(आक्षेपबाधकरीत्यन्तरनिराकरणभाष्यम्)

यदि पुनर्दीर्घाणामतपराणां प्रगृह्यसंज्ञोच्यते ?

एवमप्येकार एव एकः सवर्णान्गृह्णीयात्, ईकारोकारौ न गृह्णीयाताम् ।

किं कारणम् ?

अनण्त्वात् ॥

(प्रदीपः) **यदि पुनरिति** ॥ ननु व्यक्तिपक्षाश्रयणात् प्लुतानां न सिध्यति, न पुनस्तपरत्वात् ॥ अयमत्राशयः— आकृतिपक्ष आश्रयिष्यते । दीर्घोच्चारणाच्च प्रयत्नाधिक्यात् ह्रस्वानां न भविष्यति, प्लुतानां तु प्रवर्तिष्यते ॥ **एवमपीति** । अयं भावः– आकृतिपक्षे यथा ह्रस्वानां प्रयत्नाधिक्यान्न भवति, तथा दीर्घोच्चारणसामर्थ्याद्विशिष्टव्यक्तिस्थैवाकृतिर्गृह्यत इति प्लुताना न स्यात् । यथा स्थूलं गामानयेत्युक्ते न कृशस्यानयनं भवतीति आकृतिपक्षेऽपि विशिष्टैव दीर्घा व्यक्तिर्गृह्यते । तथा चानण्त्वादीदूतौ ग्राहकौ न स्याताम् ॥

(उद्योतः) **न पुनस्तपरत्वादिति** । तद्वक्ष्यति भाष्ये— **'दीर्घाणां चोच्यमाना प्लुतानां न प्राप्नोति'** इति ॥ **प्लुतानां त्विति** । तपरत्वाभावे इत्यर्थः । तपरत्वे तु **तपरसूत्रस्य** जातिपक्षेऽनण्यपि नियमार्थत्वान्न स्यादिति भावः ॥ ईत्वादि इत्याद्यनतिरिक्तं मन्यते ॥ **आकृतिरिति** ॥ विना व्यक्त्युच्चारणं जातिनिर्देशाभावादवश्यं व्यक्तावुच्चारणीयायां लाघवाय ह्रस्व एव प्रयोक्तव्ये गुरुदीर्घोच्चारणेन तद्व्यक्तेरुपलक्षणत्वं विहाय विशेषणत्वस्यैवाश्रयणाद्विशिष्टव्यक्तिस्थैव जातिर्गृह्यत इति न्यूनकालव्यक्तिगताया इवाधिककालव्यक्तिगाया अपि न ग्रहणमिति भावः ॥ भिन्नभिन्नव्याप्यजातिस्वीकारे तु निर्दिष्टव्याप्यजातेः प्लुतेऽभाव एवेत्यपि बोध्यम् । एत्वजातेस्तु प्लुते सत्त्वात्तेन प्लुतग्रहणं भवत्येव । ततो लघुव्यक्तेरभावाच्च ॥ नन्वेवं भाष्येऽनण्त्वादिति हेतुरसङ्गतोऽत आह—**आकृतिपक्षेऽपीति** । ईदृशे विषये तत्तदित्वादिजातिविशिष्टा व्यक्तिरेव गृह्यत इत्यर्थः ॥ जातिप्राधान्ये फलाभावात्, व्यक्तिद्वारा कार्यसंबन्धाश्रयणे गौरवाच्च, तस्यायुक्तत्वाच्च । तद्विशिष्टव्यक्तिग्रहणेऽप्यण्त्वाभावान्न तौ ग्राहकाविति भावः ॥

(आक्षेपबाधकरीत्यन्तरनिराकरणभाष्यम्)

यदि पुनर्ह्रस्वानामतपराणां प्रगृह्यसंज्ञोच्यते ?

नैवं शक्यम् । इहापि प्रसज्येत—अकुर्वहि अत्र, अकुर्वह्यत्रेति ॥

(प्रदीपः) **यदि पुनरिति** । ह्रस्वसाहचर्यादेकारोऽपि ह्रस्वशब्देनाभिधीयत इति 'ह्रस्वानां' इति बहुवचनम् । तत्र ह्रस्वनिर्देशोऽणत्वादाकृतिपक्षे वा यत्नाधिक्याभावात् भिन्नकालानां ग्रहणं सिध्यतीत्यर्थः ॥

(आक्षेपोपसंहारभाष्यम्)

तस्माद्दीर्घाणामेव तपराणां प्रगृह्यसंज्ञा वक्तव्या । दीर्घाणां चोच्यमाना प्लुतानां न प्राप्नोति ॥

(उद्द्योतः) भाष्ये—तस्माद्दीर्घाणामेव तपराणामिति । गुणान्तरयुक्तसवर्णग्रहणाशङ्कानिरासाय चेत्यर्थः ॥

(समाधानभाष्यम्)

एवं तर्हि किं न एतेन यत्नेन—'यस्य सिद्धः प्लुतः स्वरसंधिषु' इति । असिद्धः प्लुतः । तस्यासिद्धत्वात्तत्काला एव भवन्ति ॥

(आक्षेपभाष्यम्)

कथं यत्तज्ज्ञापकमुक्तम्—"प्लुतप्रगृह्या अचि" इति ?

(समाधानभाष्यम्)

प्लुतभावी प्रकृत्या—इत्येवमेतद्विज्ञायते ॥

(प्रदीपः) **प्लुतभावीति** । प्लुतो भावी यस्य सः—प्लुतभावी स्थानी प्रकृतः, तस्यैव प्रकृतिभावः ॥ ननु प्लुतस्यासिद्धत्वात्स्थान्यपि प्लुतभावित्वात् प्लुतव्यपदेशं कथं लभते ? नैष दोषः । प्लुतोऽस्य भावीति बुद्ध्या प्रकल्पनमेतत् । न च तत्र प्लुतस्यासिद्धत्वम्, अन्यथा प्लुतोऽसिद्ध इत्ययमपि व्यवहारो न स्यात् ॥

(उद्द्योतः) कर्मधारयभ्रमं व्युदस्यति—**प्लुतो भावीति** ॥ यद्यप्याश्रयात्सिद्धत्वेनापि सिध्यति, तथापि शास्त्रबाधापेक्षया लक्षणाश्रयणमुचितमिति भाष्याभिप्रायः ॥ **प्रकृत इति** । प्लुतशब्देन बोधित इत्यर्थः ॥ **बुद्ध्येति** । शास्त्रीये कार्येऽसिद्धत्वम्, न चायं व्यवहारः शास्त्रीयं कार्यमिति भावः ॥

(आक्षेपभाष्यम्)

कथं यत्तत्प्रयोजनमुक्तम् ?

(समाधानभाष्यम्)

क्रियते तन्न्यास एव—"अप्लुतवदुपस्थिते" इति ॥

(आक्षेपभाष्यम्)

एवमपि यत्सिद्धे प्रगृह्यकार्यं तत्प्लुतस्य न प्राप्नोति—"अणोऽप्रगृह्यस्यानुनासिकः" इति ॥

(प्रदीपः) कार्यकालपक्षमाश्रित्याह—**एवमपीति** । ततश्च 'अमी ३' इत्यत्र 'अप्रगृह्यस्य' इत्यनुनासिकप्रतिषेधे क्रियमाणे प्लुतस्य सिद्धत्वात्प्रगृह्यत्वाभावादनुनासिकः स्यात् ॥

(उद्द्योतः) कार्यकालपक्षमाश्रित्येति । अयं भावः—तत्र पक्षे संज्ञाशास्त्राणां न पृथक् बोधकत्वम् । पूर्वत्रासिद्धमिति चातिदेशः कार्यार्थः । कार्यज्ञानं च वाक्यार्थबोधोत्तरमिति यदेशे वाक्यार्थबोधस्तद्देशस्थत्वमेव तस्य । किं च 'पूर्वत्रासिद्धम्' इत्यस्याधिकारत्वेन पूर्वत्रेदमसिद्धमिति तदर्थः । तत्र कार्यकालपक्षे तत्तद्देशोपस्थितसंज्ञापरिभाषाणामप्यसिद्धत्वबोधनम् । एवं च प्लुतदृष्ट्याऽनुनासिकविधेरसिद्धत्वेन तदेकवाक्यतापन्नस्यास्यापि तद्दृष्ट्याऽसिद्धत्वेन प्लुतशास्त्रेऽनुपस्थितपूर्वत्रासिद्धमित्यत्रत्यपूर्वग्रहणेन—ईदूदेद्—अवसोमादित्यस्य ग्रहीतुमशक्यत्वमिति ॥ यथोद्देशे तु स्वातन्त्र्येण संज्ञादीनां कार्यबोधकत्वाभावात् प्लुतासिद्धत्वबोधनं व्यर्थमेव ॥ एतेन कार्यकालपक्षेऽपि पाठकृतपूर्वत्वाक्षतिरित्यपास्तम् ॥ भाष्ये—यत्सिद्धे प्रगृह्येति । प्लुते सिद्धकाण्डस्थे यत्प्रगृह्यकार्यमित्यर्थः । यत्प्रगृह्यकार्यदृष्ट्या प्लुतः सिद्धः स्यादिति यावत् ॥

(समाधानभाष्यम्)

एवं तर्हि किं न एतेन—'कार्यकालं संज्ञापरिभाषम्' इति, यथोद्देशमेव संज्ञापरिभाषम् । अत्र चासावसिद्धः, तस्यासिद्धत्वात्तत्काला एव भवन्ति ॥

(प्रदीपः) यथोद्देशपक्षाश्रयेण परिहारः । कथं पुनरयं पक्षः, यावता कार्यार्थत्वात्संज्ञापरिभाषस्य कार्यकालतैव न्याय्या । नैष दोषः । यदाऽनुद्दिश्य प्रयोजनविशेषं प्रयोजनमात्रमभिसन्धाय भविष्यति किंचिदनेन प्रयोजनं—इति संज्ञापरिभाषं प्रणीयते, तदा संभवत्येवायं पक्षो यथाश्रुतग्राहिप्रतिपन्नपेक्षः । महावाक्यार्थपर्यालोचनप्रवृत्तप्रतिपन्नपेक्षस्तु कार्यकालपक्षः ॥

(उद्द्योतः) **यथोद्देशेति** । नन्वत्र पक्षेऽमी ३ इत्यादौ प्लुतस्यासिद्धत्वेन ततः प्रागेव प्लुताभावपक्षेऽनुनासिकप्रतिबन्धेन फलवत्यां संज्ञायां ततः प्लुते तं द्विमात्रत्वेन पश्यन्त्या अपि संज्ञायाः पुनः प्रवृत्तौ बीजाभावात्—अल्विधित्वेन स्थानिवत्त्वाभावाच्चाप्रगृह्यत्वेनानुनासिकः स्यादिति चेन्न । संज्ञायाः कार्यार्थतया पुनः प्रवृत्तौ कार्यसिद्धिरूपबीजसत्त्वेन पुनस्तस्याः सुलभत्वात् । एतदेव ध्वनयता प्लुतस्यासिद्धत्वात्तत्काला एव भवन्तीत्येवकारः प्रयुक्तः । प्लुतात्प्राक् संज्ञायां च तत्काला एवेति तदर्थ इत्यलम् ॥ प्रणीयते=बोध्यते ॥

(इति तपरप्रयोजननिरूपणम्)

(अथ द्विवचनविशेषणताविचारभाष्यम्)

कथं पुनरिदं विज्ञायते—ईदादयो यद्द्विवचनम्—इति, आहोस्विदीदाद्यन्तं यद्द्विवचनमिति ॥

(प्रदीपः) **कथं पुनरिति** । ईदादयो यदि संज्ञिनस्तद्विशेषणं तु द्विवचनं तदा द्विवचनान्तत्वमीदादीनां न संभवतीति द्विवचनानामेवेदादीनां संज्ञया भाव्यम् । अथ द्विवचनं संज्ञि तद्विशेषणमीदादयस्तदा तदन्तविधिरप्रधानेन प्रधानस्येतीदाद्यन्तं द्विवचनमिति पक्षः ॥ तत्रोभयोरपि पक्षयोर्दोषदर्शनात्प्रश्नः ॥

(उद्योतः) ईदादय इति । प्राथम्यादुद्दतोमादित्यनेनैकरूप्याच्चेति भावः ॥ तदेवेति । अन्तशब्दोऽवयववचनस्तदन्तस्येति बहुव्रीहिश्चेत्यर्थः ॥ अथेति । संज्ञाया आनन्तर्यार्थेन विधिरित्यस्यानुग्रहाच्चेति भावः ॥

(विशेषजिज्ञासाभाष्यम्)

कश्चात्र विशेषः ?

(१४८ प्रथमपक्षे दोषप्रदर्शकवार्तिकम् ॥ १ ॥)

॥ * ॥ ईदादयो द्विवचनं प्रगृह्या इति चेदन्त्यस्य विधिः ॥ * ॥

(भाष्यम्)

ईदादयो द्विवचनं प्रगृह्या इति चेत्, अन्त्यस्य प्रगृह्यसंज्ञा विधेया-पचेते इति, पचेथे इति ॥

(प्रदीपः) पचेते इतीति । एकारोऽत्र द्विवचनं न भवति, अपि तु तस्यान्तः ॥

(उद्योतः) भाष्ये—अन्त्यस्येति । द्विवचनान्त्यस्य वर्णस्येत्यर्थः ॥

(दूषणबाधकभाष्यम्)

वचनाद्भविष्यति ॥

(प्रदीपः) वचनादिति । द्विवचनावयवे द्विवचनशब्दो वर्तिष्यत इत्यर्थः ॥

(दूषणसाधकभाष्यम्)

अस्ति वचने प्रयोजनम् ।

किम् ?

खट्वे इति, माले इति ॥

(प्रदीपः) अस्तीति । मुख्ये संभवति गौणस्य ग्रहणमन्याय्यमित्यर्थः ॥ खट्वे इति । 'अन्तादिवच्च' इत्यादिवद्भावादेकारो द्विवचनम् ॥

(उद्योतः) गौणस्येति । अधन्यत्वसामान्याल्लाक्षणिकमपि गौणपदेन गृह्यत इति भावः ॥

(दूषणबाधकद्वितीयपक्षाभ्युपगमभाष्यम्)

अस्तु तर्हि—ईदाद्यन्तं यद्द्विवचनम्-इति ॥

(१४९ द्वितीयपक्षे दूषणवार्तिकम् ॥ २ ॥)

॥ * ॥ ईदाद्यन्तमिति चेदेकस्य विधिः ॥ * ॥

(भाष्यम्)

ईदाद्यन्तमिति चेदेकस्य प्रगृह्यसंज्ञा विधेया—खट्वे इति, माले इति ॥

(प्रदीपः) एकस्येति । असहायस्येत्यर्थः । ईदूतोः केवलयोरेव संभव इति वचनसामर्थ्यात्तयोः सिध्यति, एकारान्तस्य तु द्विवचनस्य 'पचेते' इत्यादौ संभवात् 'खट्वे' इत्यत्र न सिध्यतीति दोषः ॥ 'येन विधिस्तदन्तस्य' इत्यत्र 'स्वस्य च रूपस्य' इति नाश्रितमिति दोषोपन्यासः ॥

(उद्योतः) प्रथमोपस्थितेदूत्परित्यागेन एकारान्तोदाहरणदाने बीजमाह—ईदूतोरिति ॥ नाश्रितमिति । वार्तिककृतेति शेषः ॥

(१५० द्वितीयपक्षे समाधानवार्तिकम् ॥ ३ ॥)

॥ * ॥ न वाऽऽद्यन्तवत्त्वात् ॥ * ॥

(भाष्यम्)

न वा एष दोषः ।

किं कारणम् ?

आद्यन्तवत्त्वात् । आद्यन्तवदेकस्मिन्कार्यं भवतीत्येवमेकस्यापि भविष्यति ॥

(तृतीयपक्षाभ्युपगमभाष्यम्)

अथवा एवं वक्ष्यामि—'ईदाद्यन्तम्' ईदाद्यन्तं यद्द्विवचनान्तम्-इति ॥

(प्रदीपः) अथवेति । प्रत्ययग्रहणे यस्मादिति द्विवचनेन तदन्तविधिः, पश्चाद्द्विवचनान्तमीदादिभिर्विशेष्यत इत्ययं तृतीयः पक्षो भवति—ईदाद्यन्तं यद्द्विवचनान्तमिति ॥ ननु संज्ञाविधौ प्रत्ययग्रहणेन तदन्तविध्यभावः 'सुप्तिङन्तं पदम्' इत्यन्तग्रहणेन ज्ञापित इति कथमेतत्पक्षोपपत्तिः ? चतुर्थपक्षप्रतिक्षेपाय वक्ष्यत्येवैतद्भाष्यकार इति नैतदपूर्वं चोद्यम् ॥

(उद्योतः) तदन्तविधिरिति । अस्मादेव वचनाच्छब्दस्वरूपं विशेष्यमादायेति भावः ॥ इत्ययं तृतीयः पक्ष इति । व्यपदेशिवद्भावानाश्रयणमस्य बीजम् ॥

(१५१ आक्षेपवार्तिकम् ॥ ४ ॥)

॥ * ॥ ईदाद्यन्तं द्विवचनान्तमिति चेल्लुकि प्रतिषेधः ॥ * ॥

(भाष्यम्)

ईदाद्यन्तं द्विवचनान्तमिति चेल्लुकि प्रतिषेधो वक्तव्यः । कुमार्योरगारं-कुमार्यगारम् । वध्वोरगारं-वध्वगारम् । एतदीदाद्यन्तं श्रूयते, द्विवचनान्तं च भवति प्रत्ययलक्षणेन ॥

(प्रदीपः) दोषान्तरेणेमं पक्षं निराकर्तुमाह—लुकि प्रतिषेध इति । दोषसद्भावेनैवास्य पक्षस्य निराकरणात्तदन्तविध्यभावोऽत्र नोक्तः ॥ कुमार्यगारमिति । कथं पुनरत्र द्विवचनान्तस्य समासः, यावता वृत्तौ संख्याविशेषो न गम्यते । नैष दोषः । यथा 'तावकीनः' इत्यादावादेशेन संख्याविशेषो व्यज्यते, तथेहापि सत्यां प्रगृह्यसंज्ञायां प्रकृतिभावेन द्वित्वं व्यज्येतेति दोषोपन्यासः ॥

(उद्योतः) तदन्तविध्यभावोऽत्र नोक्त इति । ईदादिभिः श्रूयमाणत्वेन द्विवचनविशेषणमेव न्याय्यमिति एतत्पक्षासंभवरूपो दोषो नोक्त इत्यपि बोध्यम् ॥ आदेशेनेति । एकार्थयुष्मदादेर्विहितेन तवकाद्यादेशेनेत्यर्थः ॥ प्रकृतिभावेनेति । अन्यथाऽनुपपद्यमानेनेत्यर्थः । एवं हि सिद्धान्ते प्रगृह्यत्वाभावेन द्वित्वव्यञ्जकाभावादस्य

प्रयोगस्यासाधुत्वापत्तिः । असाधुप्रयोगे च भगवतोऽश्रद्धेयतापत्तिः । अतः पूर्वपदार्थतावच्छेदकरूपेणैव बोधो न तु सङ्ख्यावत्त्वेनेत्येव भाष्यसंमतम् । अतो वृत्तौ सङ्ख्याऽनवगमेऽप्यनेकार्थप्रतीत्या तथाविग्रहे बाधकाभाव इति बोध्यम् ॥

(१५२ समाधानवार्तिकम् ॥ ५ ॥)

॥ * ॥ सप्तम्यामर्थग्रहणं ज्ञापकं प्रत्ययलक्षणप्रतिषेधस्य ॥ * ॥

(भाष्यम्)

यदयम् "ईदूतौ च सप्तम्यर्थे" इत्यर्थग्रहणं करोति, तज्ज्ञापयत्याचार्यः—न प्रगृह्यसंज्ञायां प्रत्ययलक्षणं भवतीति ॥

(प्रदीपः) सप्तम्यामिति । 'ईदूतौ सप्तमी' इत्येव तदन्तविधौ सति प्रत्ययलक्षणेन 'सोमो गौरी अधिश्रितः' इत्यादिषु सिद्धायां प्रगृह्यसंज्ञायामर्थग्रहणं ज्ञापयति—**प्रगृह्यसंज्ञाप्रकरणे प्रत्ययलक्षणं न भवति**–इति ॥

(गौरवाक्षेपभाष्यम्)

तत्तर्हि ज्ञापकार्थमर्थग्रहणं कर्तव्यम् ॥

(प्रदीपः) तत्तर्हीति । आद्यन्तवद्भावानाश्रयणाय तृतीयः पक्षः परिगृहीतः । तत्र च दोषप्रतिविधानार्थमधिकमर्थग्रहणं ज्ञापकार्थं कर्तव्यं भवतीति सुतरां गौरवं भवतीत्यर्थः ॥

(उद्द्योतः) सुतरामिति । अकरणात्करणं गुरु, तस्य च ज्ञापकत्वेनाश्रयणमिति सुतरां गौरवमित्यर्थः ॥

(चतुर्थपक्षाश्रयणेन समाधानभाष्यम्)

[12][न कर्तव्यम् ।] ईदादिभिर्द्विवचनं विशेषयिष्यामः, ईदादिविशिष्टेन च द्विवचनेन तदन्तविधिर्भविष्यति—ईदाद्यन्तं यद्द्विवचनं तदन्तं-ईदाद्यन्तम्—इति ॥

(प्रदीपः) ईदादिभिरिति । अत्र पक्षे 'कुमार्यगारं' इत्यत्राप्रसङ्गः । न ह्यत्रेदूदेदन्तं द्विवचनम्, किं तर्हि ? 'ओस्' इति सकारान्तम् ॥ तदन्तमिति । द्विवचनान्तम् ॥ ईदाद्यन्तमिति । ईदादिभिः साक्षात्समुदायस्य संबन्धाभावादीदादिशब्देनेदाद्यन्तमुच्यते, तेनेदाद्यन्तान्तमित्यर्थः ॥

(उद्द्योतः) ईदादिभिरिति–भाष्ये । श्रुतस्य श्रुतेन संबन्धो न्याय्य इति भावः ॥ साक्षात्–द्विवचनमनपेक्ष्य ॥ समुदायस्य–प्रत्ययान्तस्य ॥

(आक्षेपभाष्यम्)

एवमप्यशुक्ले वस्त्रे शुक्ले समपद्येतां-शुक्लीस्तां वस्त्रे-अत्र प्राप्नोति । अत्र हीदादि च द्विवचनं, तदन्तं च भवति प्रत्ययलक्षणेन ॥

(प्रदीपः) शुक्लीस्तामिति । शुक्लशब्दाद्द्विवचनं 'औ', तस्य 'नपुंसकाच्च' इति शीभावः, ततश्च्विप्रत्ययः । शीशब्दस्य 'सुपः' इति लुक् । 'अस्य च्वौ' इतीत्वं । तद्धितान्तत्वात्सुप् । तस्य 'अव्ययात्' इति लुक् । अत्र हि शीशब्द ईकारान्तं द्विवचनम्, तदन्तश्च समुदायः प्रत्ययलक्षणेनेति प्रगृह्यसंज्ञा प्राप्नोति ॥

अत्र हीदादि च द्विवचनमिति । ईदादिशब्देनेदाद्यन्तमुच्यते ॥ क्वचित्तु पाठः—'ईदाद्यन्तं च श्रूयते' इति, तत्रैवं व्याख्येयम्—ईदाद्यन्तं च श्रूयते सूत्रे, तदन्तविधिरीदादिभिर्द्विवचनस्याश्रीयत इत्यर्थः । यस्त्वयं 'अस्य च्वौ' इतीकारः, स द्विवचनस्य न कश्चिदिति न तदभिप्रायेण भाष्यं व्याख्येयम् ॥

(उद्द्योतः) नन्वत्र पक्षे न द्विवचनेनेदादि विशेष्यत इति कथमीदादि च द्विवचनमितीत्यत आह—ईदादीति । तदन्तत्वं चास्य व्यपदेशिवद्भावेन बोध्यम् ॥ श्रूयते सूत्र इति । येच्छ्रूयते सूत्रे द्विवचनं तदीदाद्यन्तमिति भाष्ये योजनेत्याशयः ॥

(समाधानभाष्यम्)

अत्राप्यकृते शीभावे लुग्भविष्यति ॥

(आक्षेपसाधकभाष्यम्)

इदमिह संप्रधार्य–लुक् क्रियतां, शीभाव इति ।

किमत्र कर्तव्यम् ?

परत्वाच्छीभावः ॥

(समाधानसाधकभाष्यम्)

नित्यो लुक् । कृते शीभावे प्राप्नोत्यकृतेऽपि प्राप्नोति ॥

(आक्षेपसाधकभाष्यम्)

अनित्यो लुक् । अन्यस्य कृते शीभावे प्राप्नोत्यन्यस्याकृते । शब्दान्तरस्य प्राप्नुवन्विधिरनित्यो भवति ।

शीभावोऽप्यनित्यः, न हि कृते लुकि प्राप्नोति । उभयोरनित्ययोः परत्वाच्छीभावः, शीभावे कृते लुक् ॥

(उद्द्योतः) अनित्यत्वेऽपि लुकः शीभावो नित्यश्चेदतुल्यबलत्वात्परत्वादिति पूर्वोक्तमनुपपन्नमतो भाष्ये शीभावोऽप्यनित्य इत्युक्तम् ॥ कृते लुकि तदप्राप्तिस्तु प्रसक्तरूपपष्ठ्यर्थस्याभावादिति भावः ॥

(आक्षेपदार्ढ्यभाष्यम्)

अथापि कथंचिन्नित्यो लुक्स्यात् । एवमपि दोषः, वक्ष्यत्येतत्–*पदसंज्ञायामन्तवचनमन्यत्र संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिप्रतिषेधार्थम्* इति । इदं चापि प्रत्ययग्रहणम्, अयं चापि संज्ञाविधिः । अवश्यं खल्वस्मिन्नपि पक्षे आद्यन्तवद्भाव एषितव्यः ॥

तस्मादस्तु स एव मध्यमः पक्षः ॥ ११ ॥

(प्रदीपः) अथापि कथंचिदिति । स्थानिविशेषानपेक्षायां कृताकृतप्रसङ्गित्वेन लुक्शास्त्रस्य प्रवर्तनादित्यर्थः ॥ अथवा नित्यत्वेन बाधकत्वं लक्ष्यते । तेनान्तरङ्गानपीति शीभावस्य लुक् बाधक इत्यर्थः ॥ एवमपि दोष इति । अचतुर्थपक्षस्योत्थानमेव नास्तीति एतत्पक्षासंभव एव दोषः ॥ अवश्यमिति । येनाश्रयणभयादयं पक्षोऽङ्गीकृतस्तस्याद्यन्तवद्भाव-

स्यासिन्नपि पक्षेऽवश्यमाश्रयणमङ्गीकर्तव्यम् । 'अमी' इत्यत्र ईकार एव द्विवचनं, न त्वीकारान्तम् ॥ **तस्मादिति** । द्वितीय एव पक्षोऽस्त्वित्यर्थः ॥

'मणीवादीनां प्रतिषेधो वक्तव्यः' इति भाष्यकारवार्तिककाराभ्यामपठितत्वादप्रमाणमेतत् । **'मणीवोष्ट्रस्य'** इति तु प्रयोगो वाशब्दस्योपमानार्थत्वस्य । 'रोदसीव' इत्यादिस्तु छान्दसः प्रयोगः । छन्दसि तु सर्वे विधयो विकल्प्यन्ते ॥ ११ ॥

(उद्द्योतः) **अमी इतीति** । खट्वे इत्यस्याप्युपलक्षणमेतत् ॥ **द्वितीय इति** । प्रत्ययांशे तदन्तविधिसत्त्वेन पक्षद्वयस्यैकत्वबुद्ध्या तस्य मध्यमत्वोक्तिरिति बोध्यम् ॥ **एतदिति** । वृत्तिकारोक्तमित्यर्थः ॥ ११ ॥

(११ प्रगृह्यसंज्ञासूत्रम् ॥ १ । १ । ५ आ. २)

अदसो मात् ॥ १ । १ । १२ ॥

(मूत्वमीत्वयोरसिद्धत्वनिराकरणाधिकरणम्)

(१५३ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ मात्प्रगृह्यसंज्ञायां तस्यासिद्धत्वादयावेकादेशप्रतिषेधः ॥ * ॥

(भाष्यम्)

मात्प्रगृह्यसंज्ञायां तस्य-ईत्वस्य ऊत्वस्य चासिद्धत्वादयावेकादेशाः प्राप्नुवन्ति, तेषां प्रतिषेधो वक्तव्यः । अमी अत्र, अमी आसते, अमू अत्र, अमू आसते ॥

(प्रदीपः) **अदसो मात् ॥ १२ ॥ मात्प्रगृह्येति** । असिन्सूत्रन्यास इत्यर्थः ॥ **ऊत्वस्य चेति** । चशब्दान्मत्वस्य च । शास्त्रासिद्धत्वाच्च स्थानिलक्षणमेव कार्यं प्राप्नोति, नादेशलक्षणमित्ययादिप्रसङ्गः ॥ 'अमी आसते' इत्यत्रायादेशः प्राप्नोति । 'अमू आसाते' इत्यावादेशः । 'अमी अत्र' इत्यत्र-एकादेशः ॥ ननु च द्विपदाश्रयत्वाद्बहिरङ्गा अयादयोऽन्तरङ्गेष्वीत्त्वादिष्वसिद्धा इति पूर्वाभावे कथं **'पूर्वत्रासिद्धं'** इतीत्त्वादीनामसिद्धत्वं स्यात् ? नैष दोषः । **'नाजानन्तर्ये-'** इति बहिरङ्गपरिभाषाया निषेधात् ॥

(उद्द्योतः) **अदसो मात् ॥ १२ ॥ अस्मिन्निति** । मात्पटिते इत्यर्थः ॥ यदि तु अदसो दादित्युच्यते, दात्परश्च पूर्वोत्तरसाहचर्यादवर्णभिन्नोऽच्-औकारैकाररूप एव, तदा न स्यादोष इति भावः ॥ इदमेव ध्वनयितुं 'अदसः प्रगृह्यसंज्ञायाम्' इति नोक्तम् ॥ नन्वीत्त्वोत्त्वयोरसिद्धत्वेऽपि अदसोमादित्यत्रेवूदिति निवर्त्य मात्परौकारैकारयोरपि प्रगृह्यत्वान्नायादिप्रसङ्गोऽत आह—**चशब्दान्मत्वस्येति** । एवं चैदौतोर्मात्परत्वाभावादेवमपि न प्रगृह्यत्वप्राप्तिरिति भावः ॥ नन्वीत्त्वादीनामसिद्धत्वेऽपि तन्निवर्तितौकाराद्यभावेन कथमयादिप्राप्तिः । किं चायादीन्प्रत्यसिद्धत्वेऽपि प्रगृह्यसंज्ञायामाश्रयासिद्धत्वेन तत्संज्ञायां तत्सामर्थ्यान्नायादयोऽत आह—**शास्त्रेति** ॥ नादेशलक्षणमिति । प्रकृतिभाव इत्यर्थः । प्रगृह्यत्वं त्वनुनासिकपर्युदासेन चरितार्थमिति भावः ॥ **एकादेशः—एङः पदान्तादतीति** ॥ **नाजानन्तर्ये इति** । अयादावजानन्तर्यादिति भावः ॥ त्रैपादिकेऽन्तरङ्गे बहिरङ्गपरिभाषाया अप्रवृत्तेर्विसर्जनीयसूत्रे भाष्ये वक्ष्यमाणत्वान्न दोष इति **परे** ॥

(आक्षेपबाधकभाष्यम्)

ननु च प्रगृह्यसंज्ञावचनसामर्थ्यादयादयो न भविष्यन्ति ॥

(प्रदीपः) **ननु चेति** । यथोद्देशपक्षे आश्रयात्सिद्धत्वं भविष्यतीत्यर्थः ॥

(उद्द्योतः) **यथोद्देशेति** । नन्वाश्रयात्सिद्धत्वेन प्रगृह्यत्वेऽपि मूत्वादेरसिद्धत्वादयादिकं स्यादेवेति चेन्न । एवमपि संज्ञाशास्त्रवैयर्थ्यादप्रत्याश्रयणेनायादिकं प्रत्यपि सिद्धत्वं ज्ञाप्यत इत्याशयात् ॥

(आक्षेपसाधकं भाष्यवार्तिकम्)

वचनार्थो हि सिद्धे ।

(भाष्यम्)

नेदं वचनाल्लभ्यम् । अस्ति ह्यन्यदेतस्य वचने प्रयोजनम् ॥

किम् ?

यत्सिद्धे प्रगृह्यसंज्ञाकार्यं तदर्थमेतत्स्यात्-"अणोऽप्रगृह्यस्यानुनासिकः" इति ॥

(प्रदीपः) कार्यकालपक्षमाश्रित्याह—**वचनार्थो हीति** । वचनस्य प्रयोजनमित्यर्थः ॥

(उद्द्योतः) भाष्ये—**यत्सिद्धे इति** । न च तत्र पूर्वसूत्रेणैव सिद्धिः । अद्विवचने तदप्रवृत्तेः । पूर्वसूत्रविषये यथोद्देशस्यैव भाष्यकृताऽङ्गीकाराच्च ॥

(आक्षेपबाधकभाष्यम्)

नैकं प्रयोजनं योगारम्भं प्रयोजयति । यद्येतावत्प्रयोजनं स्यात्तत्रैवायं ब्रूयात्—"अणोऽप्रगृह्यस्यानुनासिकोऽदसो न" इति ॥

(प्रदीपः) **नैकमिति** । अनेककार्यसिद्ध्यर्थं संज्ञासूत्रं नैकेन प्रयुज्यत इत्यर्थः । अन्यसूत्रमेकेनापि प्रयुज्यते—**'मुद्गादण्'** इत्यादि ॥ **तत्रैवायमिति** । न च तत्र 'ईदूदेत्-' ग्रहणं कर्तव्यं, मादिति वा । यस्मादणोऽवसानेऽनुनासिको विधीयते, पूर्वेण च णकारेणाण्ग्रहणमिति 'असौ-अमुके-अमुकाभ्यां' इत्यादावनुनासिकस्याप्रसङ्ग एव । तदेवं कार्यकालेऽपि संज्ञापरिभाषे प्रकरणोत्कर्षेण विधीयमाना प्रगृह्यसंज्ञा सर्वप्रगृह्यकार्यार्था सती असिद्धत्वं बाधिष्यत इत्यर्थः ॥

(उद्द्योतः) नन्वीदाद्युपजीवनायात्र करणमित्यत आह—**नचेति** । हेऽमुके अमुका इत्यादौ तु 'अदसः' इत्यावर्त्ये न विद्यते दस्य स्थाने सो यस्य, तादृशादस इत्यर्थेनानुनासिकः स्वमतेऽपि भवत्येवेति भाष्याशयमाहुः ॥ तादृशानामनभिधानमेवेत्यन्ये ॥ **प्रकरणोत्कर्षेणेति** । संज्ञाप्रकरणे उत्कर्षेण गुरुभूतन्यासेनेत्यर्थः ॥ **सर्वेति** । प्रकृतिभावानुनासिकप्रतिषेधेत्यर्थः ॥

(१५४ समाधानवार्तिकम् ॥ २ ॥)

॥ * ॥ विप्रतिषेधाद्वा ॥ * ॥

(भाष्यम्)

अथवा प्रगृह्यसंज्ञा क्रियताम्–अयादयो वा–इति । प्रगृह्यसंज्ञा भविष्यति विप्रतिषेधेन ॥

(प्रदीपः) **विप्रतिषेधाद्वेति** । 'अयावेकादेशप्रतिषेधो वा वक्तव्यः' 'विप्रतिषेधाद्वा प्रगृह्यसंज्ञा' इति विकल्पार्थो वाशब्दः । **'नैकं प्रयोजनम्'** इत्यादिस्तु परिहारो भाष्यकारेणोक्तो न वार्तिककारेणेति न तदपेक्षो विकल्पः ॥

(उद्योतः) भाष्ये—विप्रतिषेधाद्वेति । अन्तरङ्गत्वान्मूत्वादौ कृते पदान्तरसमभिव्याहारेऽयादिभ्यः परत्वात्संज्ञासिद्धौ तत्सामर्थ्यान्मूत्वादिकं प्रकृतिभावं प्रत्यपि नासिद्धम् । आश्रयाच्च संज्ञां प्रत्यपि नासिद्धमिति भावः ॥

(समाधानबाधकभाष्यम्)

नैष युक्तो विप्रतिषेधः । "विप्रतिषेधे परम्" इत्युच्यते । पूर्वा च प्रगृह्यसंज्ञा, परेऽयादयः ॥

(प्रदीपः) **नैष युक्त इति** । इष्टसिद्धये–इति भावः ॥

(उद्योतः) ननु प्रगृह्यसंज्ञाऽभिनिर्वर्तमाना—इत्यादि वक्ष्यमाणप्रकारेण घटत एव विरोध इत्ययुक्तमेतत्–इत्यत आह—इष्टेति ॥

(समाधानसाधकभाष्यम्)

परा प्रगृह्यसंज्ञा करिष्यते ॥

(प्रदीपः) **करिष्यत इति** । आश्रयिष्यते–इत्यर्थः ॥

(समाधानबाधकभाष्यम्)

सूत्रविपर्यासः कृतो भवति ॥

(प्रदीपः) इतरस्त्वगृहीताभिप्राय आह—**सूत्रविपर्यास इति** ॥

(समाधानसाधकभाष्यम्)

एवं तर्हि परैव प्रगृह्यसंज्ञा ।

कथम् ?

"कार्यकालं संज्ञापरिभाषम्", यत्र कार्यं तत्रोपस्थितं द्रष्टव्यम् । "प्रगृह्यः प्रकृत्या" इत्युपस्थितमिदं भवति "अदसो मात्" इति ॥

(प्रदीपः) अभिप्रायं प्रकाशयितुमाह—**एवं तर्हीति** ॥

(उद्योतः) भाष्ये—परैवेति । पूर्वं पाठेऽपि तत्र वाक्यार्थबोधाभावेनेति भावः ॥

कथमिति । पाठकृतं स्वगतं पूर्वत्वमनपगतमिति प्रश्नः ॥

उत्तरयति—**कार्यकालमिति** । तत्पक्षे संज्ञाशास्त्रस्य प्रदेशदेश एवार्थबोधः । तदुत्तरं च विरोधोपस्थितिस्तत्कार्यज्ञानं चेति तत्रत्यपरत्वमेव विप्रतिषेधसूत्रप्रवृत्तौ बीजमिति भावः ॥ परैवेत्येवकारेण पाठकृतं पूर्वत्वं विद्यमानमपि विप्रतिषेधसूत्रप्रवृत्तौ न नियामकमिति सूचितम् । परिभाषाणां तु तत्पक्षेऽपि तत्तद्देशेऽर्थबोधोऽस्त्येवेति तद्विषये विप्रतिषेधसूत्रप्रवृत्तौ पाठकृतमेव तन्नियामकमिति तात्पर्यम् । आकडारस्थभपदसंज्ञादिविषये तु यथोद्देशपक्ष एवेति तत्र परया पूर्वबाधसिद्धिः ॥ ष्यङः संप्रसारणमिति सूत्रस्थं भसंज्ञायाः कार्यकालत्वपरं भाष्यं त्वेकदेश्युक्तिरिति तत्रैव निरूपयिष्यामः ॥ परे तु 'परैव' इत्यस्य संज्ञापदेन तत्कार्यप्रकृतिभाव उच्यते इति भावः ॥ आशयानभिज्ञस्य प्रश्नः—कथमिति, एकदेशिन उत्तरम्—कार्यकालमित्यादीत्याहुः ॥ एतेन "कार्यकालपक्षेऽपि पाठकृतपरत्वमयादीनामेव । अन्यथा ङमो ह्रस्वादचीत्यादौ त्रिपादीस्थे कार्यकालपक्ष एव परिभाषाप्रवृत्त्या परत्वात्तत्र तस्मादित्युत्तरस्येत्येवेति सिद्धान्तासङ्गतिः, उभयोरप्येकदेशस्थत्वेन परत्वासंभवात्" इत्यपास्तम् ॥

(समाधानबाधकभाष्यम्)

एवमप्ययुक्तो विप्रतिषेधः ।

कथम् ?

द्विकार्ययोगो हि विप्रतिषेधः । न चात्रैको द्विकार्ययुक्तः । एचामयादयः, ईदूतोः प्रगृह्यसंज्ञा ॥

(प्रदीपः) **द्विकार्ययोगो हीति** । द्वाभ्यां कार्याभ्यां यो युज्यते स विप्रतिषेधविषयत्वाद्विप्रतिषेधः ॥

(उद्योतः) द्वाभ्यामिति । 'योगः' इति कर्मणि घञ् । द्विकार्यशब्दस्य पात्राद्यन्तत्वादद्गीलिङ्गस्य योगशब्देन कर्तृकरणे कृतेति समासः ॥ (भाष्ये) ईदूतोः प्रगृह्यसंज्ञेत्यस्य तत्कार्यप्रकृतिभाव इत्यर्थः ॥

(समाधानसाधकभाष्यम्)

नावश्यं द्विकार्ययोग एव विप्रतिषेधः ।

किं तर्हि ?

असंभवोऽपि । स चात्रास्त्यसंभवः ।

कोऽसावत्रासंभवः ?

प्रगृह्यसंज्ञाऽभिनिर्वर्तमाना अयादीन् बाधते, अयादयोऽभिनिर्वर्तमानाः प्रगृह्यसंज्ञाया निमित्तं विघ्नन्ति–एषोऽसंभवः । सत्यसंभवे युक्तो विप्रतिषेधः ॥

(प्रदीपः) **असंभवोऽपीति** । असंभव एव विप्रतिषेधः । स तु कदाचिद् द्विकार्ययोगो भवति, कदाचित्केवलोऽपि । तथा हि–सति संभवे द्विकार्ययोगो न विप्रतिषेधः, यथा–एकस्य धातोरडागमद्विर्वचने भवतः—अदधादिति । क्वचिदेकस्य द्विकार्ययोगाभावेऽप्यसंभवोऽस्ति, यथा–त्रपूणामित्यत्र नुम्नुटोः प्रकृतिप्रत्ययभक्तयोः परस्परनिमित्तव्याघातात् ॥ **अयादीन्बाधत इति** । प्रकृतिभावविधानात् ॥ **निमित्तमिति** । ईत्वमूत्वं च ॥

(उद्योतः) कदाचिदिति । एवंच प्रकृते केवलासंभवरूपः स इत्यर्थः । केवलद्विकार्ययोगो न सर्वथा विप्रतिषेध इत्याह—यथा हीति ॥ ईत्वमूत्वं चेति । तद्विघातेन संज्ञाऽभावे तत्कार्यप्रकृतिभावविघातः स्पष्ट एवेति भावः ॥

(समाधानबाधकभाष्यम्)

एवमप्ययुक्तः । एतोर्हि विप्रतिषेधो भवति । न चात्रेत्वोत्वे स्तः । नापि मकारः । उभयमसिद्धम् ॥

(उद्योतः) केचित्तु—संज्ञाकार्यस्य अयादिभिर्विप्रतिषेधोऽयुक्तः । वाक्यसंस्कारपक्षे मूत्वादितः पूर्वमेवायादिप्राप्त्या–मूत्वाद्युत्तरं च संज्ञायां तत्प्राप्त्या युगपत्प्राप्त्यभावात् । तस्मात् प्रगृह्यसंज्ञाशब्देन तज्जनक–मूत्वादिकं लक्षयित्वा तस्यायादिभिर्विप्रतिषेध इति वार्तिकार्थः, तमपि दूषयति–भाष्ये—एवमपीति ॥

(१५५ समाधानसाधकवार्तिकम् ॥ ३ ॥)

॥ * ॥ आश्रयात्सिद्धत्वं यथा रोरुत्वे ॥ * ॥

(भाष्यम्)

आश्रयात्सिद्धत्वं भविष्यति । तद्यथा—रुरुत्वे आश्रयात्सिद्धो भवति ॥

(प्रदीपः) आश्रयात् सिद्धत्वमिति । प्रगृह्यसंज्ञायां कार्यित्वेनाश्रयणादसिद्धत्वाभावादीत्वादीनां तेषामयादीनां च विप्रतिषेधो निरूप्यते । तथाहि—सतोर्हि विप्रतिषेधो भवतीति पूर्वपक्षे 'ईदादीनां' एव विप्रतिषेध आक्षिप्तः । तत्रायादीनां चयनं चायकः, लवनं-लावकः, अग्नेऽत्र-इत्यत्रावकाशः । ईदादीनां तु यत्रायादीनामप्रसङ्गः सोऽवकाशः—अमी स्थिताः-अमू स्थितौ-अमीभ्य इति । 'अमी अत्र' इत्यादावुभयप्रसङ्गे परत्वादीत्त्वादय एव भवन्ति ॥ अत्र व्याख्यानान्तरं क्लिष्टत्वान्नोपन्यस्तम् ॥

(उद्योतः) कार्यित्वेनाश्रयणादिति । तत्सामर्थ्यादयादीन्प्रत्यपि सिद्धत्वमित्यर्थः ॥ यथोद्देशे इदम् । 'कथं? कार्यकालं' इति तु प्रकृतिभावायादिविप्रतिषेधविषयम् । इदानीं तु स नेति स्पष्टमेव ॥ असिद्धत्वाभावादिति । ईत्वादीनामसिद्धत्वाभावादित्यन्वयः ॥ सामान्यत एवासिद्धत्वाभावबोधनादित्यर्थः ॥ तेषां—ईत्वादीनाम् ॥ परत्वादिति । ईत्वादिषु जातेषु तेषामसिद्धत्वाभावादयादीनामप्रसङ्ग एवेति भावः ॥ व्याख्यानान्तरमिति । प्रगृह्यत्वकार्यप्रकृतिभावेनायादीनां विप्रतिषेधपरमेव भाष्यम् । सतोरित्यस्य युगपत्प्राप्तयोरित्यर्थः । वाक्यसंस्कारपक्षे ईत्वादीनामसिद्धत्वेन ततः प्रागेव तत्प्राप्तिः, कृते त्वीत्वादावस्य—इति न तयोर्युगपत्प्राप्तिरिति भावः ॥ तदाह—न चात्र-इत्यादि ॥ अत्र—अयादिप्राप्तिकाले । असत्त्वे हेतुः—उभयमसिद्धं-इति । पूर्वत्रासिद्धेनेति शेषः ॥ परिहरति—आश्रयादिति । पदसंस्कारपक्ष एवात्राश्रीयत इति भावः । एवंचोभयोर्युगपत् प्राप्तिः । प्रगृह्यसंज्ञायां तत्कार्ये च तयोः सिद्धत्वादयादीन्प्रति चासिद्धत्वादित्युपपन्नो विप्रतिषेध इति ॥ वाक्यसंस्कारपक्षे कृतस्य पूर्वपक्षस्य पदसंस्कारपक्षाश्रयेण परिहार इति क्लेशः ॥

परे त्वनुक्तेदादिविप्रतिषेधखण्डनतत्समर्थनपरत्वेन व्याख्यापेक्षयेदमेव युक्तं, पक्षान्तरैरपि परिहारकरणादित्याहुः ॥

(समाधानबाधकाक्षेपभाष्यम्)

किं पुनः कारणं रुरुत्वे आश्रयात्सिद्धो भवति, न पुनर्यत्रैव रुः सिद्धः, तत्रैवोत्वमप्युच्येत ?

(प्रदीपः) न पुनर्यत्रैवेति । 'रोः सुपि' इत्यस्यानन्तरं 'अत उरति' इति वक्तव्यम् । एवं चासिद्धत्वं न बाधितं भवति । तत्र पाठक्रमेऽसिद्धत्वस्य प्राप्त्यभावात् प्लुतस्य चोत्वे सिद्धत्वात्तत्कालत्वाभावात् 'अप्लुतादप्लुते' इति न वक्तव्यं भवति ॥

(उद्योतः) रोः सुपीत्यस्यानन्तरमिति । न चैवं हशि चेत्यस्यैतदुत्तरत्वाद्रोरीति दृष्ट्याऽसिद्धत्वापत्तौ मनोरथासिद्धिः । ढो ढे लोपः-रोरीत्यनयोर्यरोऽनुनासिक इत्यतः पूर्वं पाठः कार्य इत्याशयात् ॥

(भाष्यम्)

नैवं शक्यम् ॥

(१५६ समाधानसाधकवार्तिकम् ॥ ४ ॥)

॥ * ॥ असिद्धे ह्याद्गुणाप्रसिद्धिः ॥ * ॥

(भाष्यम्)

असिद्धे हि त्वे आद्गुणस्याप्रसिद्धिः स्यात्—वृक्षोऽत्र, प्लक्षोऽत्र । तस्मात्तत्राश्रयात्सिद्धत्वमेषितव्यम् । यथा तत्राश्रयात्सिद्धत्वं भवति, एवमिहाप्याश्रयात्सिद्धत्वं भविष्यति ॥

(समाधानान्तरभाष्यम्)

अथवा—प्रगृह्यसंज्ञावचनसामर्थ्यादयादयो न भविष्यन्ति ॥

(प्रदीपः) अथ वेति । यथोद्देशपक्षाश्रयेणैतदुच्यते ॥

(उद्योतः) अनुनासिकपर्युदासेन चारितार्थ्यमाशङ्क्याह—यथोद्देशेति । एतत्-वचनसामर्थ्याद्वा० इति वार्तिकं तद्व्याख्यानभाष्यं चेत्यर्थः ॥

पूर्वभाष्यस्य व्याख्यान्तरवादिनस्तु वाक्यसंस्कारपक्षेऽप्याह—अथवेति । वस्तुतस्तु प्रकृतिभावोपस्थितसंज्ञायां तयोर्निमित्तत्वेनाश्रयणरूपवचनसामर्थ्यादयादीन्प्रत्यपि सिद्धत्वं ज्ञाप्यते इत्यर्थ इति कार्यकालेऽपि न दोषः ॥ किं च यथोद्देशेऽपि संज्ञां प्रति निमित्तत्वेनाश्रयणात्तद्दृष्ट्या मीत्वस्य सिद्धत्वेन संज्ञाया अनुनासिकप्रतिबन्धेन चारितार्थ्यमस्त्येव । प्रकृतिभावविषयकसंज्ञोपप्लवसामर्थ्याश्रयणे तु किं विशिष्य यथोद्देशाश्रयणेन ? एवमुपक्रमस्थभाष्येऽपि बोध्यमित्याहुः ॥

(समाधानान्तरभाष्यम्)

अथवा—योगविभागः करिष्यते । "अदसः" अदस ईदादयः प्रगृह्यसंज्ञा भवन्तीति । ततः—"मात्" मात्परे ईदादयः प्रगृह्यसंज्ञा भवन्तीति । अदस इत्येव ॥

किमर्थो योगविभागः ?

एको यत्तत्सिद्धे प्रगृह्यकार्यं तदर्थः, अपरो यदसिद्धे ॥

(प्रदीपः) कार्यकालतायामप्याह—अथ वेति । 'अदसः' इति संबन्धसामान्ये षष्ठी । अदसः संबन्धिन ईदूदेत इति ॥

(उद्योतः) भाष्ये-'योगविभागाद्वा' इति वार्तिकं व्याचष्टे अथवेति ॥ अदस इत्यस्य पञ्चम्यन्तत्वे उत्तरत्र मादित्यस्य विशेषणानापत्तिरत आह—संबन्धेति ॥ (भाष्ये) यत्तत्सिद्धे इति । मुत्वे इति शेषः । यत्र कार्ये मुत्वं सिद्धं तत्प्रगृह्यकार्यमित्यर्थः ॥ अपरो यदसिद्ध इति । यत्र मुत्वमसिद्धं तदित्यर्थः ॥

(आक्षेपभाष्यम्)

इहापि तर्हि प्राप्नोति—अमुया, अमुयोरिति । किंच स्यात् यद्यत्र प्रगृह्यसंज्ञा स्यात्?

प्रगृह्याश्रयः प्रकृतिभावः प्रसज्येत ॥

(प्रदीपः) इहापीति । 'अदस् टा' 'अदस् ओस्', अत्वम्, टाप्, सवर्णदीर्घत्वम् । 'आङि चापः' इत्येत्वम् । 'अदे आ' 'अदे ओस्' इति स्थिते 'अदसः' इत्यत्र 'मात् इति विशेषणाभावात्प्रगृह्यसंज्ञायां सत्यामयादेशाप्रसङ्गः ॥

(आक्षेपनिरासभाष्यम्)

नैष दोषः । पदान्तप्रकरणे प्रकृतिभावः । न चैष पदान्तः ॥

(आक्षेपभाष्यम्)

एवमपि 'अमुकेऽत्र' अत्रापि प्राप्नोति ॥

(प्रदीपः) अमुकेऽत्रेति । 'अदसः' इत्यनेन प्राप्नोति ॥

(आक्षेपबाधकभाष्यम्)

द्विवचनमिति वर्तते ॥

(आक्षेपसाधकभाष्यम्)

यदि द्विवचनमिति वर्तते 'अमी अत्र' अत्र न प्राप्नोति ॥

(आक्षेपबाधकभाष्यम्)

एवं तर्हि 'एदन्तं' इति निवृत्तम् ॥

(प्रदीपः) एदन्तमिति । ईदूतोरेव स्वरितत्वप्रतिज्ञानादिति भावः । अननुवृत्तिरेव च निवृत्तिः । यद्येवं माद्ग्रहणं न कर्तव्यम्, एद्ग्रहणनिवृत्त्यैव 'अमुकेत्र' इत्यत्राप्रसङ्गात् । नैतदस्ति । सति माद्ग्रहणे योगविभागो भवति, नान्यथा ॥

(उद्द्योतः) ननु समस्तस्यास्समुदायानुवृत्तिः स्यात्कथमेतो निवृत्तिरत आह—ईदूतोरेवेति ॥ नान्यथेति । सिद्धान्ते तु व्यर्थमेव माद्ग्रहणमिति भावः ॥

(समाधानान्तरभाष्यम्)

अथवा-आहायम्—"अदसो मात्" इति, न च ईत्वोत्वे स्तः, नापि मकारः । तत एवं विज्ञास्यामः—'मार्थादीदाद्यर्थानाम्' इति ॥

(प्रदीपः) एकयोगे परिहारान्तरमप्याह—अथ वेति ॥ मार्थादिति । मार्थ एव स्थानी मशब्देनोक्तः, ईदूदेदर्थश्चेदूदेदिति । न चास्यां कल्पनायामसिद्धत्वं भवति, बुद्धिसङ्कलनायामसिद्धत्वाभावस्योक्तत्वात् ॥

(उद्द्योतः) भाष्ये *मार्थादीदाद्यर्थानां वा* इति वार्तिकं व्याचष्टे—अथवाऽऽहेति । ननु एवं सति 'अदेऽदौ' इत्यस्यामवस्थायां प्रगृह्यत्वेऽपि मीत्वमूत्वयोः कृतयोरीकारादीनामप्रगृह्यत्वादेतद्वैयर्थ्यम्, अल्विधित्वेन प्रगृह्यत्वाभावादिति चेन्न । प्रदेशे प्रगृह्यस्थानिकस्यापि लक्षणया ग्रहणेनादोषात् ॥

(समाधानभाष्यम्)

उक्तं वा ।

किमुक्तम्?

'अदस ईत्वोत्वे स्वरे बहिष्पदलक्षणे सिद्धे वक्तव्ये, प्रगृह्यसंज्ञायां च' इति ॥

(प्रदीपः) उक्तं वेति । असिद्धत्वमेवात्र प्रतिषिद्धमित्यर्थः ॥ स्वरे इति । अचीत्यर्थः ॥ बहिष्पदलक्षण इति । द्वितीयपदव्यवस्थित इत्यर्थः । तेनैकपदव्यवस्थितेऽचि असिद्धे ईत्वोत्वे । तेन 'अमुया' 'अमुयोः' इत्यत्रायादेशो भवत्येव ॥ प्रगृह्यसंज्ञायां चेति । प्रगृह्यसंज्ञायामेव सिद्धत्वेन सिद्धे लक्ष्ये प्रपञ्चार्थः पूर्ववाक्योपन्यासः ॥

(उद्द्योतः) द्वितीयेति । द्वितीयपदस्थेऽचि यत्कार्यं तन्नासिद्धत्वं नेत्यर्थः ॥

[अन्ये तु 'अथवा वचनसामर्थ्यात्' इत्यादिभाष्यं भाष्यकृत एवोक्तिः । अत एव सांप्रतपुस्तकेषु वार्तिकापाठ इत्याहुः ॥

अन्ये तु अन्त्ये 'उक्तंवेत्यस्य(त्र)' वार्तिकत्वं मत्वा कोशे वार्तिकपाठो भ्रष्ट इत्याहुः ॥]

सिद्धे इति । प्रगृह्यत्वे सिद्धत्वमयादीन् प्रति सिद्धत्वं विना सप्रयोजनं नेति सामर्थ्यात्तान् प्रत्यपि तौ सिद्धाविति भावः ॥

(अनिष्टापत्तिनिवारणम्)

(१५७ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ तत्र सकि दोषः ॥ * ॥

(भाष्यम्)

तत्र सककारे दोषो भवति—अमुकेऽत्र ॥

(प्रदीपः) तत्र सकि दोष इति । मात्परं यदीदाद्यन्तमिति दोषोपन्यासः । पूर्वसूत्रे हि तदन्तं गृहीतमितीहापि तदन्तस्यैवानुवृत्तिरिति भावः ॥

(उद्द्योतः) विशेष्यासंनिधाने कथं तदन्तविधिरत आह—पूर्वसूत्रे इति । अर्थाधिकारादिति भावः ॥

(१५८ समाधानवार्तिकम् ॥ २ ॥)

॥ * ॥ न वा ग्रहणविशेषणत्वात् ॥ * ॥

(भाष्यम्)

न वा एष दोषः ।

किं कारणम्?

ग्रहणविशेषणत्वात् । न माद्ग्रहणेन ईदाद्यन्तं विशेष्यते ।

किं तर्हि?

ईदादयो विशेष्यन्ते-मात्परे य ईदादय-इति ॥ १२ ॥

(प्रदीपः) स्वरितत्वेन शब्दमात्रमनुवर्त्यत इति उत्तरेऽभिप्रायः । तत्र माद्ग्रहणेन श्रूयमाणमीदूदेद्विशेष्यते, तेन 'अमुकेऽत्र' इत्यत्र व्यवधानाद्दोषाभाव एव । योगविभागे दोषप्रसङ्गात् 'एदन्तमिति निवृत्तं' इत्युक्तम् । एकयोगे तु तन्निवृत्त्या न प्रयोजनमिति 'न वा ग्रहणविशेषणत्वात्' इत्युत्तरमुक्तम् ॥ १२ ॥

(उद्योतः) शब्दमात्रमिति । एवं च विशेष्याभावान्न तदन्तविधिरिति भावः ॥ १२ ॥

(१२ प्रगृह्यसंज्ञासूत्रम् ॥ १ । १ । ५ आ. ३ ॥)

शे ॥ १ । १ । १३ ॥

(अनिष्टापत्तिनिराकरणम्)

(आक्षेपभाष्यम्)

इह कस्मान्न भवति—काशे, कुशे, वंशे-इति ?

(प्रदीपः) शे ॥ १३ ॥ इह कस्मादिति । अत्र हि प्रत्यक्षमेव 'शे' इति रूपम् । 'युष्मे-अस्मे' इत्यत्र तु शकारस्याऽनुपलब्धस्याश्रवणादनुमेयमिति प्रश्नः ॥

(उद्योतः) शे ॥ १३ ॥ प्रत्यक्षमेवेति । एवंच 'इह—' इति भाष्यस्य इहैवेत्यर्थः ॥ युष्मे इति । सुपां सुलुगिति विभक्त्यादेशः शेशब्द इत्यर्थः ॥

(१५९ समाधानवार्तिकम् ॥ १ ॥)

॥ * ॥ शेऽर्थवद्ग्रहणात् ॥ * ॥

(भाष्यम्)

अर्थवतः शेशब्दस्य ग्रहणम् । न चैषोऽर्थवान् ॥

(प्रदीपः) शेऽर्थवद्ग्रहणादिति । 'स्वं शब्दस्य' इत्येवान्तरङ्गत्वादहेयत्वादसाधारणत्वाच्च रूपपरिग्रहे सिद्धे रूपवदर्थस्याप्यङ्गीकरणार्थं रूपग्रहणं कृतम् । अत्र च शशब्दोऽनर्थकः, सप्तम्येकवचनं त्वर्थवत्, तयोः समुदायोऽर्थान्तराप्रादुर्भावादनर्थकः ॥

(उद्योतः) शेश्चासावर्थवांश्च, तस्य ग्रहणादित्यर्थः । शक्तिग्रहनिरपेक्षप्रतीतिकत्वेनान्तरङ्गत्वम् । अर्थप्रतीतावपि प्रतीयमानत्वं—अहेयत्वम् । शब्दान्तरैरप्रत्यायनादसाधारणत्वम् ॥ अप्रादुर्भावः—अप्रतीतिः ॥

(एकदेशिन आक्षेपभाष्यम्)

एवमपि-हरिशे, बभ्रुशे-इत्यत्र प्राप्नोति ॥

(प्रदीपः) एवमपीति । अत्र हि मत्वर्थीयसप्तम्येकवचनयोरर्थवतोः समुदायोऽर्थवानेव, अवयवधर्मानुविधानीत्समुदायस्येति प्रश्नः ॥

(उद्योतः) मत्वर्थीयो लोमादिशः ॥

(समाधानभाष्यम्)

एवं तर्हि 'लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव' इत्येवं न भविष्यति ॥

(प्रदीपः) लक्षणेति । प्रतिपदोक्ते हि झटिति प्रतिपत्तिर्भवति, लाक्षणिके तु लक्षणानुसन्धानद्वारेण विलम्बा—इति न तस्य ग्रहणम् ॥

(सिद्धान्तिसमाधानभाष्यम्)

अथवा पुनरस्तु—'अर्थवद्ग्रहणे नानर्थकस्य' इत्येव । कथं हरिशे-बभ्रुशे-इति ?

एकोऽत्र विभक्त्यर्थेनार्थवान्, अपरस्तद्धितार्थेन । समुदायोऽनर्थकः ॥ १३ ॥

(प्रदीपः) अथ वेति । अर्थवत्समुदायस्यापि कस्यचिदानर्थक्यं, यथा—दशदाडिमादिवाक्यस्य पदार्थानां परस्परसमन्वयाभावात् । इहापि हरिशशब्दवाच्यार्थगतसंख्याधिकरणशक्तिप्रतिपादनाय प्रवृत्ता सप्तमी न शप्रत्ययमात्रप्रतिपाद्येनार्थेनान्वेतीति शेशब्दस्यानर्थक्यम् ॥ १३ ॥

(उद्योतः) आनर्थक्यमिति । प्रत्यक्षानुमानिकन्यायापेक्षया रूपग्रहणानुगतार्थवत्परिभाषा प्रबलेति भावः ॥ १३ ॥

(१३ प्रगृह्यसंज्ञासूत्रम् ॥ १ । १ । ५ आ. ४)

निपात एकाजनाङ् ॥ १ । १ । १४ ॥

(पदकृत्याधिकरणम्)

(आक्षेपभाष्यम्)

निपात इति किमर्थम् ?

(प्रदीपः) निपात एकाजनाङ् ॥ १४ ॥ निपात इति किमर्थमिति । निपातस्यैवैकाचोऽर्थवत्त्वात् प्रत्ययस्य केवलस्य प्रयोगाभावादानर्थक्यात् कल्पितरूपत्वात् कल्पनायाश्च नियमाभावात् प्रश्नः ॥

(उद्योतः) निपात० ॥ १४ ॥ आनर्थक्यादिति । अर्थवत्त्वानिश्चयादित्यर्थः । तत्र हेतुः—कल्पितरूपत्वादिति ॥ ततः किं तत्राह—कल्पनाया इति । अत एव केचित्—शतिपं, अन्ये शसिपौ वदन्ति । तत्रैतस्योऽर्थवत्त्वमिति न निश्चेतुं शक्यत इत्यर्थः ॥ ननु निपातग्रहणाभावे एकाजिति वर्णग्रहणादर्थवत्परिभाषाया अप्रवृत्त्यार्थवद्ग्रहणे मानाभाव इति चेन्न । बहुव्रीहिरित्याशयात् । गौणमुख्यन्यायस्य तु नेह प्रवृत्तिः । पर्युदासेनैवाऽऽश्रुतत्वे लब्धे एकाज्ग्रहणस्य गौणमुख्यसंग्रहार्थत्वात्—न्यायानित्यत्वाच्च ॥ एतेन "सत्यभिमाने—अनिः-एः-अभवत्—ईअभयदित्यादौ प्रगृह्यत्वं न स्याद् गौणमुख्यन्यायात्" इति परास्तम् । अत एवौदित्यत्रैव व्यन्तप्रतिषेध आरब्धः ॥

(समाधानभाष्यम्)

चकारात्र, अहारात्र ॥

(प्रदीपः) चकारात्रेति । अन्वयव्यतिरेकाभ्यां प्रत्ययस्याप्यर्थवत्त्वमिति भावः ॥ निपातोऽपि केवलो न प्रयुज्यते, द्योतकत्वात्—इति साम्यमेव निपातप्रत्यययोः ॥ अततेर्डः—'अ आगच्छ' इत्यपि प्रत्युदाहरणम् ॥

(उद्योतः) अन्वयेति । व्याकरणानुसन्धानानुगृहीताभ्यामित्यर्थः । तस्यैव चास्मच्छास्त्रप्रवृत्त्युपयोगित्वादिति भावः ॥ वस्तुतोऽनर्थकनिपातेऽपि अस्य प्रवृत्तेरोत्सूत्रे भाष्ये वक्ष्यमाणत्वादत्रार्थवत एव ग्रहणमिति न नियमः ॥ प्रश्नाशयस्तु—अनाङिति पर्युदासात् प्रत्ययस्य ग्रहणमिति । उत्तराशयस्तु—पर्युदासेन तथाऽऽश्रयणे न मानं, निपातग्रहणादेव । तेन प्रत्ययानुकरणे प्रतत्प्रवृत्तिरिति ॥ अ आगच्छेत्यत्रापि न, प्लुते प्रकृतिभावेनैव सुवार इति प्लुताभावे कथंचिदुदाहरणत्वं यदि सवर्णदीर्घे तथा बोधः ॥

(आक्षेपभाष्यम्)

एकाजिति किमर्थम् ?

(प्रदीपः) एकाजिति किमर्थमिति । एकग्रहणसामर्थ्याद्बहुव्रीहिं मन्यते, ततश्च 'प्रेदं ब्रह्म' इत्यनिष्टनिवृत्तिर्न कृतेति प्रश्नः ॥

(उद्द्योतः) एकग्रहणेति । स्वाङ्गसमुदाये स्वाङ्गत्वाभाववदच्समुदायेऽच्त्वाभावेनैकग्रहणं विनाऽपि कर्मधारयार्थलाभादिति भावः ॥

(आक्षेपबाधकभाष्यम्)

प्रेदं ब्रह्म, प्रेदं क्षत्रम् ॥

(आक्षेपबाधानुपपत्तिभाष्यम्)

एकाजित्यप्युच्यमानेऽत्रापि प्राप्नोति । एषोऽपि ह्येकाच् ॥

(आक्षेपबाधोपपत्तिभाष्यम्)

एकाजिति नायं बहुव्रीहिः—एकोऽज् यस्मिन् सोऽयमेकाच्, एकाजिति ।

किं तर्हि ?

तत्पुरुषोऽयं समानाधिकरणः—एकः अच्—एकाच्, एकाजिति ॥

(प्रदीपः) तत्पुरुषोऽयमिति । अन्तरङ्गत्वाद्वर्तिपदार्थप्राधान्यादिति भावः ॥

(उद्द्योतः) अन्तरङ्गत्वे हेतुमाह—वर्तीति ॥

(आक्षेपभाष्यम्)

यदि तत्पुरुषोऽयं समानाधिकरणः, नार्थ एकग्रहणेन ॥

(प्रत्याक्षेपभाष्यम्)

इह कस्मान्न भवति—प्रेदं ब्रह्म, प्रेदं क्षत्रम् ॥

(उद्द्योतः) भाष्ये—इह कस्मादिति । अजन्तो निपात इत्यर्थ इति प्रश्नः ॥

(प्रत्याक्षेपबाधकभाष्यम्)

अजेव यो निपात इत्येवं विज्ञायते ॥

(उद्द्योतः) अजेव य इति । निपातेनाज्विशेषणादित्यर्थः ॥

(आक्षेपभाष्यम्)

किं वक्तव्यमेतत् ?

(उद्द्योतः) किं वक्तव्यमिति । निपातस्य न्यायप्राप्तविशेष्यत्वाभावायेत्यर्थः ॥

(समाधानभाष्यम्)

न हि ॥

(आक्षेपभाष्यम्)

कथमनुच्यमानं गंस्यते ?

(समाधानभाष्यम्)

अज्ग्रहणसामर्थ्यात् । यदि ह्यत्रान्यच्च स्यात्, अज्ग्रहणमनर्थकं स्यात् ॥

(उद्द्योतः) यदि हीति । अजन्तग्रहणेऽज्ग्रहणवैफल्यमिति भावः ॥

(सामर्थ्यानुपपत्तिभाष्यम्)

अस्ति ह्यन्यदज्ग्रहणस्य प्रयोजनम् ।

किम् ?

अजन्तस्य यथा स्यात् । हलन्तस्य मा भूत् ॥

(सामर्थ्योपपत्तिभाष्यम्)

नैव दोषो न प्रयोजनम् ॥

(प्रदीपः) नैव दोष इति । ननु 'पुरोऽह्निः' इति हलन्तस्य प्रकृतिभावाद्रोरुत्वं न स्यात् । नैष दोषः, प्रगृह्यसंज्ञायां रुत्वस्यासिद्धत्वात् सकारस्य च कार्यान्तराप्रसङ्गात् । उत्वे तु रुत्वमाश्रयात्सिद्धम् ॥

(उद्द्योतः) प्रगृह्यसंज्ञायामिति । ननु सान्तस्य प्रगृह्यत्वे एकदेशविकृतन्यायेन रान्तस्यापि तत्त्वात्प्रकृतिभावः स्यादिति चेन्न । प्रकृतिभावेऽप्यसिद्धत्वात् ॥

(सामर्थ्यानुपपत्तिभाष्यम्)

एवमपि कुत एतत्—द्वयोः परिभाषयोः सावकाशयोः समवस्थितयोः "आद्यन्तवदेकस्मिन्" "येन विधिस्तदन्तस्य" इति च,—इयमिह परिभाषा भविष्यति—"आद्यन्तवदेकस्मिन्" इति, इयं च न भविष्यति—"येन विधिस्तदन्तस्य" इति ? ॥

(प्रदीपः) एवमपीति । अन्यतरनिवृत्त्याऽज्ग्रहणस्यार्थवत्त्वादज्मात्रं गृह्यते तदन्तं निरस्यते, विपर्ययस्तु न भवतीति विशेषाभावात् प्रश्नः ॥ पारार्थ्यसामान्यात् संज्ञाऽतिदेशौ परिभाषाशब्देनोक्तौ ॥ सावकाशयोरिति । निरवकाशस्य बाधकत्वादेवमुक्तम् । तत्र तदन्तविधेरवकाशः—'ओरावश्यके' लाव्यं—पाव्यम्—इति । आद्यन्तवद्भावस्यावकाशः—'मिदचोऽन्त्यात्परः'—तानि—यानीति । अत्र हि साक्षादन्त्यग्रहणमस्तीति तदन्तविध्यभावः ॥ समवस्थितयोरिति । इह प्राप्तयोः ॥

(उद्द्योतः) अथ निपातस्य विशेष्यतया अजन्त इति व्याख्यानेऽपि अज्ग्रहणसामर्थ्यान्मुख्याजन्तपरिग्रहेण केवलाज्रूपव्यावृत्तिरज्ग्रहणस्य फलं स्यादिति मनसि निधाय पृच्छति—एवमपीति—भाष्ये ॥ अन्यतरनिवृत्त्येति । निपातस्य विशेषणत्वे तदन्तपरिभाषाऽप्रसक्तिरेव निवृत्तिः । विशेष्यत्वे त्वजिति विशेषणसामर्थ्यात्तदन्तस्यैव ग्रहेण मुख्याजन्तपरिग्रहादाद्यन्तवदित्यस्य निवृत्तिरिति भावः ॥ विपर्ययः—निपातस्य विशेष्यत्वेनाजन्तपरिग्रहः केवलाचो निवृत्तिरिति ॥ इति विशेषाभावादिति । अग्रे च कारणाभावादित्यर्थः ॥ संज्ञा—येन विधिरिति । अतिदेशः—आद्यन्तवदिति ॥ लाव्यमिति । 'लङ् शब्दे' इत्यत आवश्यके ण्यदनभिधानादेति भावः ॥

(सामर्थ्यानुपपत्तिनिराकरणभाष्यम्)

आचार्यप्रवृत्तिर्ज्ञापयति—इयमिह परिभाषा भविष्यति—"आद्यन्तवदेकस्मिन्" इति, इयं न भवि-

ष्यति–"येन विधिस्तदन्तस्य" इति । यदयं–'अनाङ्' इति प्रतिषेधं शास्ति ॥

(प्रदीपः) आचार्यप्रवृत्तिरिति । यदि तर्हि लिङ्गेन तदन्तविधिर्निराक्रियते तदा तन्मूलाद्यन्तवत्परिभाषा कथं प्रवर्तेत? नैष दोषः, 'आद्यन्तवत्—' इत्यस्योपस्थानाय तदन्तविधिः प्रथमं सन्निधीयते, पश्चात्तु लिङ्गात् परित्यज्यते ॥ अथ वा लिङ्गादज्ग्रहणं निपातेन विशेष्यत इति विशेष्येण तदन्तविधेरभावादतिदेशस्यापि मा भूत् प्रवृत्तिः, तत्फलसंपत्त्या तूक्तम्—परिभाषा भविष्यतीति ॥

(उद्योतः) यदि तर्हीति । एवं च इयमिह भवतीति भाष्यमनुपपन्नमिति भाव. ॥ ननु पूर्वं प्रवर्त्य पश्चात्परित्यागापेक्षयाऽप्रवृत्तौ लाघवमित्यभिप्रेत्याह—अथवेति ॥

(समाधानभाष्यम्)

एवं तर्हि-सिद्धे सति यदज्ग्रहणे क्रियमाणे एकग्रहणं करोति तज्ज्ञापयत्याचार्यः–'अन्यत्र वर्णग्रहणे जातिग्रहणं भवति' इति ॥

किमेतस्य ज्ञापने प्रयोजनम्?

दम्भेर्हल्ग्रहणस्य जातिवाचकत्वात् सिद्धम् इति यदुक्तं तदुपपन्नं भवति ॥

(प्रदीपः) एवं तर्हीति । संज्ञाया विधीयमानत्वात् प्राधान्यात् संज्ञिनो गुणत्वात् पशुना यजेतेतिवत् संख्याया विवक्षायां सिद्धायामेकग्रहणमन्यत्र जातिसंप्रत्ययार्थम् । अच्समुदायग्रहणाशङ्काया निरासार्थं ह्येकग्रहणं ज्ञापनफलं संपद्यते ॥ किं पुनः स्यात् यद्यत्राच्समुदायस्य ग्रहणं स्यात्? उच्यते–इह 'अइउ अपेहि' इति समुदायस्यैका संज्ञा स्यात्, नावयवानाम्; समुदायैकाज्द्विर्वचनवत्–इत्यन्त्यस्यैव प्रकृतिभावायणादेशो न स्यात्। पूर्वयोस्तु स्वरसंधिः स्यात्। अच्समुदायपरिग्रहानुरोधाच्च निपातसमुदायो गृह्येत, एकनिपातस्याच्समुदायस्याभावात् ॥

(उद्योतः) ननु एकग्रहणाभावेऽच्समुदायस्य स्यादिति तन्निवृत्त्यर्थमेकग्रहणं, तत्राह—संज्ञाया इति ॥ गुणत्वादिति । संज्ञोपकारकत्वादित्यर्थः । पशोरपि यागोपकारकत्वाद्गुणत्वम् । न हि यागः पश्वर्थः, अपि तु यागार्थः पशुः । ग्रहं संमार्ष्टीत्यादौ तु ग्रहार्थत्वात्संमार्गस्य ग्रहस्य प्राधान्यमिति च तद्गतसंख्या विवक्षितेति भावः ॥

परे तु संज्ञा स्वकार्यद्वारा संज्ञ्युपकारिका, न तु संज्ञी संज्ञोपकारकः । अन्यथा ग्रहोऽपि कर्मत्वेन संमार्गार्थः स्यादिति विधेयविशेषणं विवक्षितमनुवाद्यविशेषणमविवक्षितमिति मीमांसकमर्यादैव ज्यायसी, भाष्यसंमता च–इतीदं चिन्त्यम् । तस्मात् स्वाङ्गसमुदाये स्वाङ्गत्वाभावादच्समुदायेऽच्त्वाभावाच्च तद्ग्रहणप्रसक्तिरित्येकग्रहणं विनाऽपि सिद्धिरिति तज्ज्ञापकमिति भाष्याशय इत्याहुः ॥

(भाष्ये)-जातिग्रहणमित्यस्य तज्जात्याश्रयानेकव्यक्तिग्रहणमिति भावः । अन्यथा जातिग्रहणेऽपि जातेरेकैकव्यक्तिव्यङ्ग्यतयाऽसंगतिरेव । प्रवृत्तिनिमित्ततया जातिग्रहणस्य सर्वत्र सत्त्वेन तस्यावक्तव्यत्वाच्च ॥ इहेत्यादि । अत्रेदं चिन्त्यम्–समुदायसंज्ञयाऽवयवानामननुग्रहात्तत्र द्विर्वचनन्यायः । नापि निपातसमुदायस्य निपातग्रहणेन ग्रहणम्–स्वाङ्गसमुदायस्य स्वाङ्गग्रहणेनेव, एकैकत्र सूत्रचारितार्थ्याद्–इति । तस्मात्तितउशब्दैकदेश अउशब्दानुकरणे उक्तसमुदायानुकरणे वाऽनितिपरे निपातसंज्ञके 'अउ अकरोत्' इत्यादौ प्रगृह्यत्वं स्यात्तद्वारणायैकग्रहणमिति तत्त्वम् ॥ भाष्ये–दम्भेरिति । दम्भः सनि दम्भ इच्चेतीत्वे सनीवन्तेति इडभावपक्षे इक्समीपो नकारः, न ततो झलादिः सन् परः, यतश्च भात्परः सन् न स इक्समीप इति हलन्ताच्चेति कित्त्वाभावे 'अनिदिताम्-' इति नलोपो न स्यादिति चोद्ये जात्याश्रयानेकसेक्समीपत्वं–सनश्च तस्मात्परत्वम्–इति कित्त्वे धिप्सतीति सिद्धिरित्यर्थः । अनेन सामीप्यमव्यवहिते एवेति सूचितम् ॥

(आक्षेपभाष्यम्)

अनाङिति किमर्थम्? ॥

(प्रदीपः) अनाङिति किमर्थमिति। ङिदङितोराकारयोर्विषयविभागप्रदर्शनाय प्रश्नः ॥

(उद्योतः) प्रदर्शनाय–प्रदर्शनं कारयितुमित्यर्थः ॥

(समाधानभाष्यम्)

आ उदकान्तात्–ओदकान्तात् ॥

(आक्षेपभाष्यम्)

इह कस्मान्न भवति—आ एवं नु मन्यसे, आ एवं किल तदिति?

(प्रदीपः) इह कस्मादिति । अनुबन्धनिवृत्तौ विशेषापरिज्ञानात् प्रश्नः ॥

(समाधानभाष्यम्)

सानुबन्धकस्येदमाकारस्य ग्रहणम्, अननुबन्धकश्चात्राऽऽकारः ॥

(आक्षेपभाष्यम्)

क पुनरयं सानुबन्धकः क पुनरयं निरनुबन्धकः?

(समाधानभाष्यम्)

'ईषदर्थे क्रियायोगे मर्यादाभिविधौ च यः ।
एतमातं ङितं विद्याद्वाक्यस्मरणयोरङित्' ॥१॥१४॥

(प्रदीपः) अर्थवशात् विशेषावसाय इत्युत्तरम् ॥ ईषदर्थे–आ उष्णं–ओष्णमिति । 'आङीषदर्थे' इति चोक्तम् ॥ क्रियायोगे–आ इतः–एतः, प्रादिषु हि ङित् पठ्यते ॥ 'आङ् मर्यादाभिविध्योः' इति च समासविधौ ङिन्निर्दिष्टः–आ उदकान्तात्–ओदकान्तात्, आ अहिच्छत्रात्–आहिच्छत्रादिति ॥ विना तेन–इति मर्यादा, सह तेन–इत्यभिविधिः ॥ पूर्वप्रक्रान्तस्य वाक्यार्थस्यान्यथात्वद्योतनयाऽऽकारः प्रयुज्यते–आ एवं नु मन्यसे, नैवं पूर्वममंस्थाः संप्रति मन्यस इति । वाक्यारम्भसूचनायाऽऽकार इत्यपरे ॥ तथा स्मृतेः सूचक आकारः प्रयुज्यते ततः स्मृतोऽर्थो निर्दिश्यते—आ एवं किल तदिति ॥१४॥

(उद्द्योतः) किंचिद्विधानायोपात्तस्यान्यविधानाय पुनरुपादानमन्वादेशः । प्रकृते च विधेर्द्वयाभावाद् 'एतं' इत्येनादेशो न कृत इत्याहुः ॥ विना तेनेत्यादि । यथा-आकाशी वृष्टो देव इत्यादौ काशीमभिव्याप्य काशीं वर्जयित्वेति वाऽर्थः ॥ १४ ॥

(१४ संज्ञासूत्रम् ॥ १ । १ । ५ आ. ५)

ओत् ॥ १ । १ । १५ ॥

(सूत्रवैयर्थ्यनिराकरणाधिकरणम्)

(आक्षेपभाष्यम्)

किमुदाहरणम् ?

(समाधानभाष्यम्)

आहो इति, उताहो इति ॥

(समाधानबाधकभाष्यम्)

नैतदस्ति प्रयोजनम् । निपातसमाहारोऽयम् । आह-उ-आहो इति । उत आह-उ-उताहो इति । तत्र "निपात एकाजनाङ्" इत्येव सिद्धम् ॥

(प्रदीपः) **ओत् ॥ १५ ॥ निपातसमाहारोऽयमिति** । अनर्थकानामपि निपातानां 'कमीमिदु' इत्यादीनां दर्शनादर्थभेदाभावेऽपि निपातसमाहारत्वमुक्तम् ॥

(उद्द्योतः) **ओत् ॥ १५ ॥ दर्शनादिति** । वेदे, चादीनां पादपूरणार्थानां च लोकेऽपीत्यादिः ॥ **अर्थभेदाभावेऽपि** ॥ तस्यानात्वाभावेऽपि अथवा अनर्थकाः, निपातसमुदाय इवार्थवानिति भावः । उशब्दोऽत्र निरनुबन्धकः । तेन 'उञः' इत्यनेन सिद्धिरिति न भ्रमितव्यम् ॥

(समाधानसाधकभाष्यम्)

एवं तर्ह्येकनिपाता इमे ॥

(प्रदीपः) **एवं तर्हीति** । चादिषु तथा पाठादिति भावः ॥

(समाधानान्तरभाष्यम्)

अथवा प्रतिषिद्धार्थोऽयमारम्भः । ओ षु यातं मरुतः । ओ षु यातं बृहती च शक्वरी । ओ चित्सखायं सख्या ववृत्याम् (ऋ० १०।१०।१) ॥

(प्रदीपः) **ओ षु यातमिति** । आ उ-ओ इत्यत्रान्तवद्भावाद्वत्त्वमाङ्-इति 'अनाङ्' इति प्रतिषेधः प्राप्नोति, पर्युदासे तु न दोषः । तत्र 'आङ्' सदृशस्योकारस्याङा सहैकादेश आदिवद्भावादुकारग्रहणेन गृह्यत इति सिध्यत्येव प्रगृह्यसंज्ञा । तस्याश्च प्रयोजनं क्वचिच्छाखायाम्—**ओ अयातम्**—इति पाठे प्रकृतिभावः ॥

(उद्द्योतः) **पर्युदासे त्विति** । वस्तुतः पर्युदासेऽपि दोषः, आङ्भिन्नत्वस्याशास्त्रीयत्वात् । न च स्वाश्रयमाङ्भिन्नत्वम्, आङ्त्वस्य पूर्वान्तवत्त्वेनातिदेशेऽतिदिश्यमानविरुद्धस्वाश्रयधर्मप्रयुक्तकार्यस्य निवृत्तेरतिदेशस्वभावसिद्धत्वात् । न चान्तवत्त्वमेवं दुर्लभं, शास्त्रीयकार्याभावादिति वाच्यम् । तत्रापि प्रतिषेधस्य गम्यतया शास्त्रतात्पर्यविषयत्वेन प्रगृह्यत्वाभावस्य शास्त्रीयतयाऽन्तवत्त्वप्रवृत्तेरिति बोध्यम् ॥ तस्याश्चेति । प्रगृह्येषु पदपाठे इतिशब्दप्रयोगनियमादपि फले विशेषो बोध्यः ॥

(च्व्यन्ते सूत्रप्रवृत्तिनिराकरणाधिकरणम्)

(१६० आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ ओतश्च्विप्रतिषेधः ॥ * ॥

(भाष्यम्)

ओदन्तो निपात इत्यत्र च्व्यन्तस्य प्रतिषेधो वक्तव्यः । अनदः-अदः-अभवत्=अदोऽभवत्, तिरोऽभवत् ॥

(प्रदीपः) **अदोऽभवदिति** । च्व्यन्तत्वेनात्र निपातत्वम्, **'ऊर्यादिच्वि-'** इत्यत्र निपाताधिकारात् । प्रतिषिद्धार्थत्वादस्य कथमत्र प्राप्तिरिति चेत्, उभयार्थत्वाददोषः । तथा ह्योदन्तस्य निपातस्य प्रगृह्यसंज्ञा विधीयमाना प्रतिबन्धाभावात् 'अदोऽभवत्' इत्यत्रापि भवतु, **ओ षु यातमि**त्यत्रापि परत्वात् 'अनाङ्' इति प्रतिषेधं बाधत इति प्रतिषिद्धार्थमपि स्यादिति को विरोधः ?

(उद्द्योतः) **भाष्ये—ओतश्च्वीति** । पूर्वसूत्रवदत्राप्यर्थाधिकाराद्गौणमुख्यन्यायस्याप्रवृत्तिरित्याशयः ॥ **प्रतिषिद्धार्थस्यापीति** । प्रतिषिद्धसंज्ञकं पदं प्रतिषिद्धपदेनोच्यते ॥ **परत्वादिति** । निषेधाश्च बलीयांस इत्यस्य तु नायं विषयः, तस्य पूर्वेण सह पाठात्तन्निषेधकत्वादिति भावः ॥

(आक्षेपबाधकभाष्यम्)

न वक्तव्यः । 'लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य' इत्येवं न भविष्यति ॥

(प्रदीपः) ओकारस्य प्रतिपदोक्तस्य ग्रहणमित्युत्तरम् ॥

(उद्द्योतः) **प्रतिपदोक्तस्येति** । न च प्रतिषिद्धार्थोऽयमारम्भ इति पूर्वभाष्यासङ्गत्याऽनैतत्परिभाषाया अप्रवृत्तिरेवानित्यत्वाद्वा न्वितेति वाच्यम् । असैकदेशयुक्तत्वात् ॥

(आक्षेपसाधकभाष्यम्)

एवमपि—अगौः-गौः समपद्यत—गोऽभवद्, अत्र प्राप्नोति ॥

(प्रदीपः) **एवमपीति** । ओकारस्यात्र प्रतिपदोक्तत्वमस्ति, **'गमेर्डो'** इति साक्षादुच्चारणात् । यस्य हि साक्षादुच्चारणं नास्ति **'आहुणः'** इत्यादिसामान्यलक्षणेन यद्रूपं निष्पाद्यते तल्लाक्षणिकमुच्यते ॥

(उद्द्योतः) तद्ध्वनयन् भाष्ये-आह—**एवमपीति** ॥ ननु लक्षणेन प्रतिपादितत्वादिदमपि लाक्षणिकमत आह—**यस्य हीति** ॥

(समाधानभाष्यम्)

एवं तर्हि "गौणमुख्ययोर्मुख्ये कार्यसंप्रत्ययः" इति । तद्यथा—'गौरनुबन्ध्योऽजोऽग्नीषोमीयः' इति न वाहीकोऽनुबध्यते ॥

(प्रदीपः) एवं तर्हीति । गुणादागतो गौणः, यथा गोशब्दस्य जाड्यादिगुणनिमित्तोऽर्थो वाहीकः । मुखमिव प्रधानत्वान्मुख्यः । तत्र 'स्वं रूपं–' इत्यत्र रूपग्रहणेनार्थपरिग्रहस्य ज्ञापितत्वादर्थवतः कार्येण भवितव्यम् । स चार्थः प्राथम्यान्मुख्य एव गृह्यते । गौणे ह्यर्थे शब्दः प्रवर्तमानो मुख्यार्थारोपेणैव प्रवर्तते । अनियतश्च गौणोऽर्थः । तस्माल्लौकिकोऽयं न्यायः— 'गौणमुख्ययोः–' इति ॥ 'गोऽभवत्' इत्यत्र जाड्यादिना धर्मेण गोत्वमारोपितमिति गौणत्वमर्थस्य । गोऽभवदित्यत्र च वृत्तौ प्रकृतेः कर्तृत्वं, संवीभवन्ति ब्राह्मणा इति बहुवचननिर्देशात् । प्रकृतौ च गोत्वमारोपितं, न मुख्यमिति प्रगृह्यत्वाभावः ॥

(उद्योतः) प्रधानत्वात्–अर्थान्तरप्रतीतिनिरपेक्षतया प्रतीयमानत्वात् ॥ तादृशार्थबोधकशब्दस्यापि गौणत्वं मुख्यत्वं च बोध्यम् । गौणमुख्यन्यायबीजं दर्शयितुमाह—तत्र स्वं रूपमिति ॥ प्राथम्यमेवोपपादयति—गौणे हीति । आरोपाय हि पूर्वं तदुपस्थितिरावश्यकीति भावः ॥ मुख्यार्थारोपेणेति । आरोपितसिंहत्ववान् माणवकादिसमभिव्याहारे सिंहशब्दार्थ इति भावः ॥ मुख्यस्यैव ग्रहणे युक्त्यन्तरमाह—अनियतश्चेति । सिंहशब्दस्य माणवकालीवर्दादिषु प्रयोगादिति भावः ॥ एतेन—वर्णग्रहणे लक्षणप्रतिपदोक्तपरिभाषाऽप्रवृत्तेराकारस्य लाक्षणिकत्वमित्यादि चिन्त्यमित्यपास्तम्, अनयैव तस्यापि वारणात् । छायामश्वेत्यादेस्तव्यापकस्य लक्षणप्रतिपदोक्तपरिभाषाऽनित्यत्वमात्रज्ञापकतया वर्णग्रहणे सर्वत्र तदप्रवृत्तौ मानाभावाच्च ॥ न चैवमपि अर्थवत्परिभाषामूलकत्वात्तदेव विशिष्टरूपोपादानविषयेति कथमत्र वर्णग्रहणे प्रवर्तता, तत्रैवार्थोपस्थितेः सत्त्वादिति वाच्यम् ॥ 'निपातः' इति विशिष्टरूपोपादानसत्त्वात् ॥ निपातसंज्ञा हि चादिपदोपस्थितचादीनां सत्वे संभवेऽर्थवतामेवेति ये सार्थकास्तेषां निपातपदेनापि तत्तदर्थविशिष्टानामेवोपस्थितिरिति प्रकृतसूत्रस्थनिपातपदेन मुख्यार्थकनिपातानामेव ग्रहणम्, न तु गौणार्थकानामिति भावः ॥ एवंच कार्यकालपक्षेऽपि 'च्व्यन्ता निपाताः' इत्यस्यात्रानुपस्थितिरेतत्परिभाषावशात् । विशिष्टरूपपदेन चार्थवद्रूपमेवोच्यते ॥ प्रकृते गौणत्वमुपपादयति—जाड्यादिनेति ॥ आरोपे बीजमाह—प्रकृतेः कर्तृत्वमिति । एवंच गोऽभवदित्यस्य गोभिन्नकर्तृकं गोसदृशरूपेण भवनमर्थः । यत्र च योगीश्वरशापादिना मुख्यगोरूपप्राप्तिस्तत्र च्विर्नेष्यते इति गोसदृशरूपेण भवनप्रतीतेस्तस्य गौणत्वमिति भावः ॥ ननु सुवर्णपिण्डः खदिराङ्गारसदृशे कुण्डले भवत इति भाष्ये विकृतेरपि कर्तृत्वदर्शनादुक्तं—वृत्ताविति । एवंच च्व्यन्ते प्रकृतेरेव कर्तृत्वमिति भावः ॥ प्रकृतेरेव कर्तृत्वे हेतुमाह—संवीभवन्तीति ॥

(समाधानबाधकभाष्यम्)

कथं तर्हि वाहीके वृद्ध्यात्वे भवतः—गौस्तिष्ठति, गामानयेति ?

(समाधानसाधकभाष्यम्)

अर्थाश्रय एतदेवं भवति । यद्धि शब्दाश्रयम्, शब्दमात्रे तद्भवति । शब्दाश्रये च वृद्ध्यात्वे ॥ १५ ॥

(प्रदीपः) शब्दाश्रये चेति । स्वार्थे वृत्तात् प्रातिपदिकाद्विभक्त्युत्पन्नायां कार्येषु कृतेषु शब्दान्तरसंनिधानाद्गौणत्वं प्रतीयते । तस्यां च स्वार्थस्य मुख्यव्यपदेशो नास्ति, गौणापेक्षया सम्बन्धिशब्दत्वात् मुख्यव्यपदेशस्य; गौणाभावेऽभावात्— शब्दाश्रये चेत्युक्तं, न त्वेवात्रार्थो नापेक्ष्यते । तत्र यथा 'श्वेतं छागमालभेत' इति गुणद्रव्ययोः श्रौतः क्रियासंबन्धः, वाक्यीयात्तु न्यायात् पश्चात् परस्परेण । एवं 'गां वाहीकमानय' इति पूर्वं क्रियाभिसंबन्धापेक्षया विभक्त्युत्पन्नायां वाक्यीयात्तु न्यायात् सामानाधिकरण्याद्गौणार्थप्रादुर्भावो भवतीति 'पदकार्येष्वेवायं न्यायो न प्रातिपदिककार्येषु' इत्युक्तम्— 'शब्दाश्रये च' इति ॥ १५ ॥

(उद्योतः) ननु शब्दाश्रये चेतिभाष्यस्यार्थरहितवर्णमात्राश्रये इत्यर्थः प्रतीयते, स चायुक्तः, सेर्वनामस्थानाम्शसाक्षिप्तप्रातिपदिकस्य 'ओतः' इत्यनेन विशेषणादनयोरपि विशिष्टशब्दाश्रयत्वादत आह—स्वार्थे इति । स्वार्थादिप्रयुक्तकार्येण पूर्णस्य पदस्यार्थप्रतिपादनाय प्रयोगार्हस्य पदार्थान्तरान्वये बाधप्रतिसन्धाने गौणार्थप्रतीतेरिति भावः । आक्षेपे, आक्षिप्तस्य वा शाब्देऽन्वये मानाभावाच्च ॥ गौणापेक्षयेति । मुख्यशब्दस्य गौणापेक्षया संबन्धिशब्दत्वात्, गौणाभावे=गौणस्य बुद्ध्यसंनिधाने मुख्यव्यपदेशस्य=मुख्यपदस्याभावादित्यन्वयः ॥ एवंच शब्दाश्रये चेति भाष्यस्य मुख्यव्यपदेशरहितस्वार्थबोधकप्रातिपदिकरूपशब्दाश्रये–इत्यर्थः । पदव्यपदेशरहितस्य कार्यित्वेनाश्रयणमिति फलितमिति तात्पर्यम् ॥ ननु द्वितीयादेः कर्मत्वाद्यर्थकस्य कारकत्वज्ञानसापेक्षतया गां वाहीकमानयेत्यादौ विशिष्टस्य क्रियासंबन्धेन कर्मत्वेऽपि तदभिधानाय जायमाना द्वितीया समुदायस्याप्रातिपदिकत्वात्प्रत्येकं प्रवर्तते, ततश्च पूर्वमेव गौणत्वादात्वं न स्यादत आह—तत्रेति ॥ श्रौतः क्रियासंबन्ध इति । द्वितीयाश्रुत्यनुपपत्त्या कल्पित इत्यर्थः ॥ विभक्त्यन्तेन हि उपस्थितार्थस्य क्रियान्वय इति ततः प्राक् गुणे साक्षात्परंपरासाधारण्येन, द्रव्ये च साक्षात् सामान्यतः क्रियाजन्यफलाश्रयत्वादिविवक्षयोभयत्र विभक्तिरिति भावः ॥ वाक्यीयात्तु न्यायात्–आकाङ्क्षादिमूलकशक्तया । पश्चात्–विभक्त्युत्पत्त्यनन्तरम् ॥ एवमिति । द्वितीयादेः सामान्यतः क्रियासंबन्धज्ञानापेक्षत्वात् तज्ज्ञानमूलकद्वितीयाद्युत्पत्तौ गोपदार्थस्य वाहीकान्वयः पश्चादेव । एवंच कर्मणोरेव विशेष्यविशेषणभावः, न तु विशिष्टस्य कर्मत्वमिति भावः ॥ यत्तु–विभक्त्यर्थस्य क्रियाकारकसंबन्धरूपत्वेन तयोः संबन्धबोधः श्रुतिकृत इति श्रुतेर्वाक्यापेक्षया शीघ्रं प्रवृत्त्या प्रथमं तयोरन्वयबोधः पश्चाद्गुणद्रव्ययोः परस्परान्वयबोधः । एवं गां वाहीकमानयेत्यादावपि–इति कैयटार्थं व्याख्याय दूषयन्ति—गां वाहीकं पाठयेत्यादौ यत्र गौणार्थप्रादुर्भावं विना क्रियासंबन्ध एवासंभवी तत्र पूर्वमेव गौणत्वावगतेरात्वाद्यनापत्तेरिति, तदेतेन परास्तम् । विभक्त्यन्तस्यैव प्रयोगेण तत उपस्थितानामर्थानामितरान्वयेन प्रातिपदिकमात्रार्थेन पूर्वमन्वय इत्यस्य वक्तुमप्यशक्यत्वाच्च, तादृशबोधद्वयकल्पने गौरवाच्च, अनुभवाभावाच्च ॥ किं च–अपदस्याप्रयोगेण बोद्धृभिः सर्वत्र पदस्यैव गौणार्थत्वग्रहेण 'अश्वं त्वं संपद्यते' 'अमहान्महान्भूतस्त्वद्भवति' इत्यादौ भाष्यप्रयोगे स्वाद्यादेशदीर्घादीनां करणेन चास्य न्यायस्य पदकार्यमात्रविषयत्वम्, उक्तविशिष्टरूपके इत्यपि बोध्यम् । अत एवात इमि-

त्यादेः श्वशुरसदृशास्याऽत्यमित्यर्थेऽपि प्रवृत्तिः । किं च गामित्युक्ते सर्वा क्रिया प्रसक्तेत्याद्यर्थवत्सूत्रस्थभाष्यबलात्संस्कृत्य संस्कृत्य पदान्युत्सृज्यन्ते तेषां यथेष्टमभिसंबन्धो भवति-इति वृद्धिसूत्रस्थभाष्याच्च सामान्यतः क्रियाजन्यफलाश्रयत्वादेरेव द्वितीयादिनियामकत्वेन मदुक्तव्याख्यैव तस्योचिता । प्रयोक्ताऽपि पदान्येवार्थे मुख्ये गौणे वा प्रयुयुक्षति, न तु प्रातिपदिकादिक्रमेणेति सूच्यते—पदकार्येष्विति ॥ सामानाधिकरण्यादिति । इदमुपलक्षणं, पठनादिक्रियाऽन्वयादित्यपि बोध्यम् ॥ १५ ॥

(१५।१६ प्रगृह्यसंज्ञादेशिसूत्रम् ॥ १ । १ । ५ आ. ६)

उञः ॥ १ । १ । १७ ॥

ऊँ ॥ १ । १ । १८ ॥

(अनिष्टापत्तिवारणाधिकरणम्)

(आक्षेपभाष्यम्)

इह कस्मान्न भवति—आहो इति, उताहो इति ?

(प्रदीपः) उञ ऊँ ॥ १७-१८ ॥ इह कस्मादिति । निपातसमाहारं मत्वा प्रश्नः ॥

(उद्द्योतः) उञ ऊँ ॥ १७-१८ ॥ प्रश्न इति । एवं चात्र ऊँ आदेशः प्राप्नोतीति भावः ॥

(आक्षेपबाधकभाष्यम्)

'उञः' इत्युच्यते । न चात्रोञं पश्यामः ॥

(आक्षेपसाधकभाष्यम्)

उञोऽयमन्येन सहैकादेश उञ्ग्रहणेन गृह्यते ॥

(आक्षेपबाधकभाष्यम्)

आचार्यप्रवृत्तिर्ज्ञापयति-'नोञ एकादेश उञ्ग्रहणेन गृह्यते' इति । यदयं "ओत्" इत्योदन्तस्य निपातस्य प्रगृह्यसंज्ञां शास्ति ॥

(प्रदीपः) यदयमिति । एकादेशे कृते आदिवद्भावात् संज्ञासिद्धिः ॥

(उद्द्योतः) संज्ञासिद्धिरिति । 'निपात एकाच्–' इत्यनेनेत्यर्थः ॥ स्थानिवद्भावेन तु नैतल्लभ्यम्, एकादेशस्यान्यवृत्तिधर्मत्वात् । एकादेशस्यान्यत्वमात्रवृत्तिधर्मस्तु नायम्, 'उञ्' इति समुदायेऽपि सत्त्वाद् । तेनान्तादिवद्भावेन ताद्रूप्यानतिदेशेऽपि न दोषः ॥

(आक्षेपसाधकभाष्यम्)

नैतदस्ति ज्ञापकम् । उक्तमेतत्—'प्रतिषिद्धार्थोऽयमारम्भः' इति ॥

दोषः खल्वपि स्यात्, यद्युञेकादेश उञ्ग्रहणेन न गृह्येत । जानु उ अस्य रुजति-जानू अस्य रुजति, जान्वस्य रुजति-"मय उञो वो वा" इति वत्वं न स्यात् ॥

(उद्द्योतः) भाष्ये—यद्युञ् इति । सामान्येन ज्ञापकमिति भावः । वत्वाभावपक्षे ऊँ आदेशो न स्यादित्यपि दोषो बोध्यः ॥

(सिद्धान्तिनः समाधानभाष्यम्)

एवं तर्ह्योकनिपाता इमे ॥

अथ वा द्वावुकाराविमौ । एकोऽननुबन्धकः । अपरः सानुबन्धकः । यथोऽननुबन्धकस्तस्यैष एकादेशः ॥

(योगविभागाधिकरणम्)

(१११ सिद्धान्तवार्त्तिकम् ॥ १ ॥)

॥ * ॥ 'उञः' इति योगविभागः ॥ * ॥

(भाष्यम्)

'उञः' इति योगविभागः कर्तव्यः । "उञः", शाकल्यस्याचार्यस्य मतेन प्रगृह्यसंज्ञा भवति । उ इति, विति । ततः "ऊँ", उञ ऊँ इत्ययमादेशो भवति शाकल्यस्याचार्यस्य मतेन । दीर्घोऽनुनासिकः प्रगृह्यसंज्ञकश्च ऊँ इति ॥

(प्रदीपः) इह रूपत्रयं साध्यम्—उइति-विति-ऊँ इति, तच्चैकयोगे न सिध्यति । एकयोगे हि 'उञः' इति श्रुतिरादेशेन श्रुतत्वात् संबध्यते, न प्रगृह्यसंज्ञया । सा 'निपात एकाजनाङ्' इति नित्यैवास्य भवति । शाकल्यश्रुत्यनुवृत्त्या चादेशे विकल्पिते रूपद्वयं स्यात्—उ इति-ऊँ इति । न तु 'विति' इति, तदर्थमाह—उञ इति योगविभाग इति । 'उञः' इत्यत्र 'शाकल्यस्येतौ' 'प्रगृह्यं' इति चानुवर्तते । तत्र प्रगृह्यसंज्ञैव शाकल्यस्य मतेन विधीयते, नान्येषामिति स्मृत्यन्तरानुसन्धानद्वारेण विभाषा संपद्यते । उ इति-वितीति । 'ऊँ' इत्यत्र च यदि 'शाकल्यस्य' इति नापेक्ष्यते, तदा प्रगृह्यस्योञो नित्यमादेशः स्यात् । ततश्च 'विति, ऊँ इति' एते द्वे एव रूपे स्याताम् । तस्माच्छाकल्यग्रहणानुवृत्त्या आदेशविकल्पे सति त्रीणि रूपाणि सिध्यन्ति ॥

(उद्द्योतः) नित्यैवेति । आदेशाभावपक्षे इत्यर्थः ॥ न तु वितीति । न च 'उ इति' इत्यस्य निरनुबन्धकोकारमादाय सिद्धत्वेन शाकल्यानुवृत्तिसामर्थ्यात्पक्षे 'विति' इति भविष्यतीति वाच्यम् । मयः परत्वे 'किम्विति' इत्यादौ मकारसहितनिरनुनासिकवकारघटितरूपासिद्धिप्रसङ्गात् । शाकल्यानुवृत्तिसामर्थ्यान्निपातेति प्रगृह्यत्वाभावे मय इति वत्वस्यासिद्धत्वेनेकोयणचीति वत्वेऽनुस्वारापत्तेः । उ इतीत्यतः सानुबन्धकबोधस्यापीष्टत्वेन तदनापत्तेश्चेति भावः । अन्ये तु अनेन प्रकरणात् प्रगृह्यत्वस्य-ऊँ आदेशस्य च विधानेन तस्य निपात इति प्रगृह्यसंज्ञापवादत्वादेतदादेशविकल्पे ऊँ इति-वितीति सिद्धयति, न तु 'उ इति,' अतो योगविभागः ॥ न चापवादे विशिष्टे ऊँ आदेशे असति निपातेति प्रगृह्यत्वं स्यात्, अप्रवर्तमानापवादस्योत्सर्गबाधकत्वाभावात् । अत एव पारेमध्ये इत्यव्ययीभावाभावे उत्सर्गः षष्ठीसमासो भवतीति वाच्यम् । प्रगृह्यपदस्य सर्वत्र साक्षादुद्देश्यसंब-

न्वस्य क्लृप्तत्वेनात्र विधेयविशेषणत्वे मानाभावात् । सर्वं विधानेन वाक्यभेदस्याप्यभावात्स्थानिवद्भावेन च ऊँ इत्यस्य प्रगृह्यकार्यं बोध्यम्। एवंच पक्षे प्रगृह्यत्वाभावेऽप्यस्य तात्पर्यांश्चैतदभावे निपात इत्यस्य प्रवृत्तिरित्याहुः ॥ प्रगृह्यस्येति । अनुवर्तमानप्रगृह्यपदस्यादेशेन संबन्धे उञमात्रस्य नित्यं प्रगृह्यसंज्ञकस्य ऊँभावस्य विधानापत्तौ योगविभागेन प्रगृह्यसंज्ञाविधानस्य वैयर्थ्यापत्तेरनुवर्तमानप्रगृह्यपदं पञ्चम्यन्ततया विपरिणमय्य स्थानिना संबध्यत इति भावः ॥ द्वे एवेति । न च 'उ इति' इति रूपमपि निरनुबन्धकोकारमादाय सिद्धम्, सानुबन्धकप्रतीत्यनापत्तेः । मयः परत्वे 'किम्विति' इत्यादौ मकारसहितनिरनुनासिकवकारघटितरूपासिद्धिप्रसङ्गाच्च । वस्तुतस्तु उञ इत्यस्यात्रानुवृत्तस्यार्थाधिकारादप्रगृह्यपरतैव, प्रगृह्यमिति चादेशविशेषणमेव, तथैव भाष्यस्वरसादिति 'ऊँ इति—उ इति' च रूपे स्यातां न तु वितीति तदर्थं विकल्पानुवृत्तिः । ऊँ इति[10] दीर्घोच्चारणात्प्रगृह्यपदस्यात्र संबन्ध इति सर्वमवदातम् ॥

(योगविभागवैयर्थ्यभाष्यम्)

किमर्थो योगविभागः ?

(उद्द्योतः) किमर्थो योगविभाग इति । प्रगृह्यत्वादेशयोः शाकल्यमते एव प्राप्त्या एकप्रयोग एव प्रवृत्तिः स्यात् । एवंच—ऊँ इति-वितीति च रूपे । ते चैकयोगेऽपि सिध्यत इति प्रश्नः ॥ एवंचैकयोगे वितीति न सिध्यतीति प्रागुक्तकैयटश्चिन्त्य एवेति बोध्यम् ॥

(१६२ योगविभागप्रयोजनवार्तिकम् ॥ १ ॥)

॥ * ॥ ऊँ वा शाकल्यस्य ॥ * ॥

(भाष्यम्)

शाकल्यस्याचार्यस्य मतेन ऊँ विभाषा यथा स्यात् । ऊँ इति, उ इति । अन्येषामाचार्याणां मतेन-विति ॥ १७ ॥

(प्रदीपः) **ऊँ वा शाकल्यस्येति** । शाकल्यश्रुतेरेव फलं वाग्रहणेन प्रतिपादयति । एतदेव व्याचष्टे—'शाकल्यस्य विभाषा यथा स्यात्' इति प्रगृह्यसंज्ञाऽऽदेशश्च । तत्र यद्यपि पूर्वसूत्रेषु फलरूपतया निर्देशात् प्रदेशेष्विव प्रगृह्यशब्दो द्विवचनाद्यभिधेयः, तथापीह 'उञः' इति षष्ठीनिर्देशात् स्वरूपपदार्थकः संपद्यते ॥१७॥

(उद्द्योतः) **शाकल्येति** । एवं च योगविभागसामर्थ्यात् शाकल्यानुवृत्तिसामर्थ्याच्च तत्त्वं यथाश्रुतम्, किं तु विकल्पमात्रतात्पर्यकमिति विकल्पद्वयेन सकलेष्टसिद्धिरिति भावः । एवंच शाकल्यमत एव विकल्पः फलितः । तदाह—भाष्ये—शाकल्यस्य विभाषेति ॥ शाकल्यमते 'ऊँ' आदेशविकल्पे यत्फलति तद्दर्शयति—प्रगृह्यसंज्ञाऽऽदेशश्चेति । तन्मते पर्यायेणोभयं सिध्यतीत्यर्थः ॥ ननु प्रगृह्यमित्यस्य प्रथमान्तस्य कथमुञ इत्यनेन षष्ठ्यन्तेनान्वय इत्यत आह—यद्यपीति ॥ फलरूपतयेति । फलं संज्ञाया बोध्यतया संज्ञिनः । फलपदेन च तद्बोधकं पदं लक्ष्यते । तद्रूपतया-तत्समानविभक्तिकतयेत्यर्थः ॥ द्विवचनाद्यभिधेय इति बहुव्रीहिः । प्रगृह्यशब्दवदभिन्नं द्विवचनादीति बोधः ॥ प्रगृह्यशब्दत्वेन च द्विवचनादि प्रगृह्यपदाभिधेयमिति बोध्यम् ॥ स्वरूपपदार्थक इति । उञो वाचकं प्रगृह्यपदमित्यर्थादिति भावः ॥ वस्तुतः पूर्वत्रापि शब्दपर एव । शब्दार्थयोरभेदात्सामानाधिकरण्यम्, पटः शुक्ल इतिवत् । प्रकृते तु पटस्य शुक्ल इत्यत्रेवोक्तरीत्या वैयधिकरण्येनान्वय इति न कश्चिद्दोषः ॥ केचित्तु प्रदेशे वृद्धिपदाभिन्ना आदैच इति उपस्थितिः । संज्ञावाक्ये तु तथा शाब्दबोधः । द्विवचनाद्यभिधेय इत्यस्य द्विवचनादिविशेष्यकबोधजनक इत्यर्थः । षष्ठीसमभिव्याहारे तु विशेष्यतया स्वरूपपदार्थक इति कैयटं योजयन्ति ॥ १७ ॥

(१७ प्रगृह्यसंज्ञासूत्रम् ॥ १ । १ । ५ आ. ८)

ईदूतौ च सप्तम्यर्थे ॥ १ । १ । १९ ॥

(अर्थग्रहणप्रयोजननिरूपणाधिकरणम्)

(अर्थग्रहणाक्षेपे श्लोकवार्तिकम् ॥)

ईदूतौ सप्तमीत्येव

(भाष्यम्)

ईदूतौ सप्तमीत्येव सिद्धम्, नार्थोऽर्थग्रहणेन ॥

(प्रदीपः) **ईदूतौ च सप्तम्यर्थे ॥१९॥ ईदूतौ सप्तमीत्येवेति** । सप्तमीसहचरितं यदीदूदन्तं सप्तम्यां वा परतस्तत् प्रगृह्यसंज्ञं भवतीत्येवं प्रत्ययलक्षणेन लुप्तायामपि सप्तम्यां 'सोमो गौरी अधिश्रितः' इत्यादौ भविष्यति प्रगृह्यसंज्ञेति **प्रश्नः** ॥

(उद्द्योतः) **ईदूतौ च०** ॥ १९ ॥ ईकारोकारात्मकसप्तम्या असंभवं मत्वाऽऽह—**सप्तमीसहेत्यादि** । तात्पर्यानुपपत्त्या च लक्षणेति भावः ॥ **सप्तम्यां वेति** । सप्तमीति पदं लुप्तसप्तमीकं व्याख्यास्यत इति भावः ॥ जघन्यवृत्तिकल्पनापेक्षयेदं न्याय्यमिति तात्पर्यम् ॥ **लुप्तायामपीति** । न लुमतेति निषेधस्तु अनित्यत्वान्न सप्तम्यां परत इत्यर्थेऽपीति भावः ॥

(समाधाने श्लोकवार्तिकम् ॥)

लुप्तेऽर्थग्रहणाद्भवेत् ।

(भाष्यम्)

लुप्तायां सप्तम्यां प्रगृह्यसंज्ञा न प्राप्नोति ।

क्व ?

सोमो गौरी अधिश्रितः (ऋ० ९।१२।३) । इष्यते चात्रापि स्यादिति । तच्चान्तरेण यत्नं न सिध्यतीत्येवमर्थमर्थग्रहणम् ॥

(प्रदीपः) **लुप्त इति** । संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिप्रतिषेधादसत्यर्थग्रहणे सप्तम्या एव संज्ञिनीत्वादसत्याश्च कार्याभावात् प्रत्ययनिमित्तं यत्रान्यस्य कार्यं विधीयते तत्रैव प्रत्ययलक्षणस्य सद्भावात् 'गौरी' इत्यत्राप्रसङ्गादर्थग्रहणं कृतम् । अर्थग्रहणे सति अर्थनिमित्ता संज्ञेयं भवति, न प्रत्ययनिमित्ता—इति लोपेऽपि सिध्यति ॥

(उद्योतः) ननु प्रत्ययग्रहणेन तदन्तविधौ ईकारान्तं यत्सप्तम्यन्तमित्यर्थे प्रत्ययलक्षणेन सिद्धं 'सोमो गौरी' इति, तत्राह—संज्ञेति ॥ सप्तम्या एवेति । सप्तमीपदस्य लुप्तसप्तम्यन्तत्वे सप्तमीसहचरितलाक्षणिकत्वे च न मानमिति भावः ॥ यद्यपीकारोकारसप्तम्योरसंभव एव तत्र मानं तथापि वचनादित्यादिना तद्वक्ष्यतीत्यत्र तात्पर्यम् ॥ असत्याश्च कार्याभावादिति । प्रगृह्यसंज्ञाकार्यं हि सन्धिकार्याभावफलकप्रकृतिभावः, लुप्ते षष्ठ्यर्थप्रसक्त्यस्य निरूपयितुमशक्यत्वेन सन्धिकार्याप्राप्त्या प्रकृतिभावानुपयोगात्तत्कार्याभाव इत्यर्थः ॥ तदेवाह—प्रत्ययनिमित्तमित्यादिना ॥

(समाधानबाधकभाष्यम्)

नात्र सप्तमी लुप्यते ।
किं तर्हि ?
पूर्वसवर्णोऽत्र ॥

(प्रदीपः) **पूर्वसवर्ण इति ।** सति च पूर्वसवर्णे एकादेशे चादिवद्भावाद्भवतीकारः सप्तमीति सिद्धा संज्ञा ॥

(उद्योतः) **पूर्वसवर्णे इति ।** स च सुपां सुलुगित्यनेन ॥

(समाधानसाधकं श्लोकवार्तिकम् ॥)

पूर्वस्य चेत् सवर्णोऽसावाडाम्भावः प्रसज्यते ॥ १ ॥

(भाष्यम्)

यदि पूर्वसवर्णः, आट्-आम्भावश्च प्राप्नोति ॥

(प्रदीपः) **आडाम्भाव इति ।** एकादेशं बाधित्वाऽऽडामौ स्याताम् ॥

(उद्योतः) **एकादेशमिति ।** परत्वाद्वर्णादाङ्गस्य बलीयस्त्वाच्चेति भावः । एवञ्च ङयन्ते गौरीत्यादौ लुक आवश्यकत्वेन तदर्थमर्थग्रहणमिति तात्पर्यम् ॥

(समाधानबाधकभाष्यम्)

एवं तर्हि आहायम्-ईदूतौ सप्तमी-इति, न चास्ति सप्तमी ईदूतौ । तत्र वचनाद्भविष्यति ॥

(प्रदीपः) **वचनादिति ।** सर्वत्रैव सप्तमी लुप्यत इति वचनसामर्थ्यात् सप्तमीशब्देन सप्तमीसहचरितस्य ग्रहणान्मुख्यकल्पनाऽसंभवे गौणी कल्पना गृह्यते-इत्याश्रयणात् सिध्यतीति भावः ॥

(उद्योतः) **सर्वत्रैवेति ।** ननु यसीत्यादिभ्यो ङौ दीर्घे तनू इत्यादौ ओस्सुपोः पूर्वसवर्णादेशे च ईदूदन्तसप्तमीसंभवात्कथमेतदिति चेन्न । **'ईदूत्सप्तमी प्रगृह्यम्' 'अदसः' 'एच्च द्विवचनम्'** इत्येव सिद्धे स्थलान्तरे 'ईदूतौ सप्तमी' इति गुरुवचनसामर्थ्येन सप्तमीसहचरितग्रहणमिति भाष्याशयान्न दोष इति केचित् ॥ तन्न । न चास्ति सप्तमी ईदूताविति भाष्यासङ्गतेः । तस्मादेतद्भाष्यप्रामाण्यात्तेषामनभिधानमिति तत्त्वम् ॥

(समाधाने श्लोकवार्तिकम् ॥)

वचनाद्यत्र दीर्घत्वम्

(भाष्यम्)

नेदं वचनाल्लभ्यम् । अस्ति ह्येतस्य वचने प्रयोजनम् ॥

किम् ?

यत्र सप्तम्या दीर्घत्वमुच्यते—'दृतिं न शुष्कं सरसी शयानम्' (ऋ०७।१०३।२) इति । सति प्रयोजने इह न प्राप्नोति—'सोमो गौरी अधिश्रितः' इति ॥

(प्रदीपः) मुख्यकल्पना सम्भवत्येवेत्याह—**यत्रेति ।** सरसीत्यत्र । सरःशब्दात् परस्य ङिशब्दस्य 'इयाडियाजीकाराणामुपसंख्यानम्' इतीकारे कृते भवतीकारः सप्तमीति तत्रैव स्यात्, न तु 'गौरी' इत्यत्रेति भावः ॥

(उद्योतः) **सरःशब्दादिति ।** सरस्शब्दस्याद्युनन्तत्वेनाद्युदात्तत्वेऽपि स्वरव्यत्ययात् 'दृतिं न शुष्कं सरसी शयानं' इत्यत्र सरसीत्यस्यान्तोदात्तत्वं बोध्यम् ॥

(समाधानबाधकं श्लोकवार्तिकम् ॥)

तत्रापि सरसी यदि ।

(भाष्यम्)

तत्रापि सिद्धम् ।
कथम् ?
यदि सरसीशब्दस्य प्रवृत्तिरस्ति ।
अस्ति च लोके सरसीशब्दस्य प्रवृत्तिः ।
कथम् ?
दक्षिणापथे हि महान्ति सरांसि सरस्य इत्युच्यन्ते ॥

(प्रदीपः) **सरसी यदीति ।** 'यदि' इति सम्भावनायाम् । तस्मात् स्थितमेतत्-वचनात् सर्वत्र लुप्तायामपि सप्तम्यां भविष्यतीति नार्थोऽर्थग्रहणेन ॥

(उद्योतः) निराकर्तुः संशयार्थो यदिशब्दोऽनुपपन्न इत्यत आह—**संभावनायामिति ।** शास्त्राणि चेत्प्रमाणं स्युरितिवद्-संदिग्धे संदिग्धवचनमिदमिति भावः ॥ सरसीशब्दो यदि ङीषन्तस्तदाऽन्तोदात्तत्वं न्यायसिद्धम् । असुन उगन्तत्वान्ङीबन्तत्वे तु स्वरव्यत्ययादेव तत्त्वम् । एवं च ततो लुकैवोक्तप्रयोगे सिद्धे इयाडिति वार्तिके ईकारादेशो न विधेय इति भाष्याशयः ॥ तस्मात्पूर्वोक्तरीत्या वचनसामर्थ्याल्लुप्तेऽपि सिद्धिः ॥

(समाधाने श्लोकवार्तिकम् ॥)

ज्ञापकं स्यात् तदन्तत्वे

(भाष्यम्)

एवं तर्हि ज्ञापयत्याचार्यः-'न प्रगृह्यसंज्ञायां प्रत्ययलक्षणं भवति' इति ।

किमेतस्य ज्ञापने प्रयोजनम् ?

कुमार्योरगारं-कुमार्यगारम्, वध्वोरगारं-वध्वगारम् । प्रत्ययलक्षणेन प्रगृह्यसंज्ञा न भवति ॥

(प्रदीपः) **ज्ञापकमिति ।** 'ईदूदेत्' इत्यत्र तृतीयचतुर्थपक्षयोरित्यर्थः ॥ इह प्रगृह्यसंज्ञाप्रकरणे यदि प्रत्ययलक्षणं स्यात् तदा 'ईदूतौ च सप्तमी' इत्येव सप्तमीसहचरितं सप्तम्यां वा परतो

यदीदूदन्तं तत् प्रगृह्यमिति प्रत्ययलक्षणेन लुप्तायामपि सप्तम्यां संज्ञा भविष्यतीति किं-अर्थग्रहणेन, तत् क्रियमाणं प्रत्ययलक्षणाभावं सूचयति ॥

(उद्योतः) सप्तमीसहचरितत्वं च प्रत्ययलक्षणेन बोध्यम् ॥

(समाधाने श्लोकवार्तिकम् ॥)

मा वा पूर्वपदस्य भूत् ॥ २ ॥

(भाष्यम्)

अथवा पूर्वपदस्य मा भूदित्येवमर्थमर्थग्रहणम् । वाप्यामश्वः-वाप्यश्वः, नद्यामातिः-नद्यातिः ॥

(प्रदीपः) संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधेरभावात् तदन्तपक्षस्तत्र नैव स्थित इति ज्ञापनफलाभावादाह—**मा वेति** ॥ **वाप्यश्वो नद्यातिरिति** । 'संज्ञायां' इति समासे कृते सप्तमीसहचरितमीकारान्तं पूर्वपदमिति स्यात् प्रगृह्यसंज्ञा-इति तदर्थमर्थग्रहणम् ॥

(उद्योतः) **संज्ञायामितीति** । अत एवाग्रे भाष्ये जहत्स्वार्थावृत्तिरिति सङ्गच्छते । न च वाक्येन संज्ञाऽनवगमादस्य नित्यसमासत्वे वाप्यामश्व इति विग्रहो नोचित इति वाच्यम् । वाक्यात्संज्ञिनोऽनवगमेन नित्यसमाससदृशत्वेऽपि न तद्विधायके वाग्रहणासंबन्ध इति समासघटकीभूतानां तद्विषये विग्रहाभावे मानाभावात् । ध्वनितं चेदं द्वितीयतृतीयेति सूत्रे भाष्ये-इति तत्रैव निरूपयिष्यते ॥ सप्तमीसहचरितमिति । प्रत्ययलक्षणेनेति भावः ॥

(आक्षेपभाष्यम्)

अथ क्रियमाणेऽप्यर्थग्रहणे कस्मादेवात्र न भवति ?

(प्रदीपः) **अथेति** । अस्त्येवात्र सप्तम्यर्थ इति प्रश्नः ॥

(समाधानभाष्यम्)

जहत्स्वार्था वृत्तिरिति ॥

(प्रदीपः) **जहत्स्वार्थेति** । समासस्यैवार्थवत्त्वात् पूर्वोत्तरपदयोर्वर्णवदानर्थक्यात् सप्तम्यर्थोऽत्र नास्तीत्यर्थः ॥

(उद्योतः) वर्णवदानर्थक्यादिति । **संज्ञायामिति** समासेऽस्य रूढिशब्दत्वादवयवार्थाप्रतीतेरिति भावः । 'वाप्यामश्वः' इति विग्रहप्रदर्शनं तु रथन्तरादिपदानां रथेन तरतीत्यादिविग्रहप्रदर्शनवद्बोध्यम् । अत एवं—**'जहत्स्वार्था तु तत्रैव यत्र रूढिर्विरोधिनी'** इति वृद्धैरुक्तम् ॥

(आक्षेपभाष्यम्)

अथाजहत्स्वार्थायां वृत्तौ दोष एव ॥

(उद्योतः) भाष्ये—अथाजहत्स्वार्थायामिति । सुप्सुपेति समासेन केवलयौगिके इत्यर्थः ॥

(समाधानभाष्यम्)

अजहत्स्वार्थायां च न दोषः । समुदायार्थोऽभिधीयते ॥

(श्लोकवार्तिकसंग्रहः)

ईदूतौ सप्तमीत्येव, लुप्तेऽर्थग्रहणाद्भवेत् ।
पूर्वस्य चेत् सवर्णोऽसावाडाम्भावः प्रसज्यते ॥१॥
वचनाद्यत्र दीर्घत्वं, तत्रापि सरसी यदि ।
ज्ञापकं स्यात् तदन्तत्वे, मा वा पूर्वपदस्य भूत् ॥ २ ॥ १९ ॥

(प्रदीपः) **समुदायार्थ इति** । वृत्तौ हि पूर्वपदं स्वार्थमप्यभिधत्ते प्रधानार्थमपि-इति स्वार्थसंसृष्टस्य प्रधानार्थस्याभिधानात् पांसूदकवत् स्वार्थस्य विवेकानवगमात् समुदायार्थो वृत्तौ संसृष्टरूप एवाभिधीयते । सप्तम्यर्थग्रहणेन यावानेवार्थो वाक्ये सप्तम्यन्तेनाभिधीयते केवलोऽसंसृष्ट उद्भूतस्तस्यैवेह ग्रहणमिति समासे न भवति प्रगृह्यसंज्ञा ॥ १८ ॥

(उद्योतः) **प्रधानार्थमपीति** । अश्वादिशक्तिसमुदायशक्तिसहकारेण गृहीतशक्तिकाद्वापीपदात्स्वार्थविशिष्टप्रधानार्थस्यैवोपस्थितेरित्यर्थः ॥ तत्र **समुदायशक्तिः** संसर्गांश एव । तदाह—**स्वार्थसंसृष्टस्येत्यादि** ॥ **विवेकानवगमात्**—पृथगनुपस्थितेरित्यर्थः । पांसूदकं मिलितं यथा संसृष्टमेव ज्ञानविषयो न तु पृथक्, तथा समासात्संसृष्ट एवोपस्थितिविषयो न तु पृथगित्यर्थः ॥ **यावानित्यस्य** विवरणं—**केवल** इति । कैवल्यं विवृणोति—**असंसृष्ट उद्भूत इति** । असंसृष्टत्वं-विशेषणाविशिष्टत्वम् । उद्भूतत्वं—इतराविशेषणत्वमिति बोध्यम् ॥ **समुदायरूपोऽर्थः**—पूर्वपदार्थविशिष्ट उत्तरपदार्थोऽभिधीयते—अभिधाभिः परस्परसहकारेणोपस्थाप्यत इति भाष्यार्थः ॥ **अर्थग्रहणसामर्थ्यात्**सप्तम्यर्थमात्रपर्यवसन्नार्थकमर्थग्रहणमिति भावः ॥ गौरीत्यादौ स्वस्यैव गौर्यादिपदानां सप्तम्यर्थपर्यवसन्नत्वम् । समभिव्याहृतपदान्तरार्थानन्वयित्वेनोपस्थितिविषयत्वस्यैव सप्तम्यर्थपर्यवसन्नत्वरूपत्वात् ॥ न चार्थग्रहणेऽपि गौरीत्याद्यसिद्धिः, सप्तम्यर्थे ईकाराद्यभावात् । ईदाद्यन्तमित्यर्थस्तु दुर्लभो विशेष्याभावादिति वाच्यम् । सामर्थ्याच्छब्दरूपं विशेष्यमादाय तदन्तविधिरिति भावात् ॥ १८ ॥

(इति प्रगृह्यसंज्ञाप्रकरणम्)

(१८ घुसंज्ञासूत्रम् ॥ १ । १ । ५ आ. ६)

दा धा घ्वदाप् ॥ १ । १ । २० ॥

(इष्टानुपपत्तिनिराकरणाधिकरणम्)

(१६३ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ घुसंज्ञायां प्रकृतिग्रहणं शिदर्थम् ॥ * ॥

(भाष्यम्)

घुसंज्ञायां प्रकृतिग्रहणं कर्तव्यम् । दाधाप्रकृतयो घुसंज्ञा भवन्तीति वक्तव्यम् ।

किं प्रयोजनम् ?

आत्वभूतानामियं संज्ञा क्रियते । सा आत्वभूतानामेव स्यात्, अनात्वभूतानां न स्यात् ।

ननु च भूयिष्ठानि घुसंज्ञाकार्याणि अर्धधातुके,

तत्र चैते आत्वभूता दृश्यन्ते ॥

'शिदर्थम्' । शिदर्थं प्रकृतिग्रहणं कर्तव्यम् । शित्यात्वं प्रतिषिध्यते तदर्थम् । प्रणिदयते, प्रणिधयतीति ॥

(प्रदीपः) दाधाघ्व० ॥२०॥ दाधाशब्दयोर्घुसंज्ञा विधीयमाना रूपान्तरयुक्तानां दोदेङ्धेटां न प्राप्नोतीत्याह—घुसंज्ञायामिति ॥

किं प्रयोजनमिति । दोदेङ्धेटामेजन्तानामनुकरणानि व्यवस्थाप्यात्वे कृते ददातियच्छतिदधात्यनुकरणानां चैकशेषे कृते द्वन्द्वनिर्देशात् सिद्धा दोदेङ्धेटामपि घुसंज्ञा, कृतात्वानां चैषां स्थानिवद्भावेन सिद्धेति प्रश्नः ॥

आत्वभूतानामिति । भवतेः प्राप्त्यर्थात् "आधृषाद्वा" इति विभाषितणिचः कर्तरि कर्मणि वा क्तप्रत्ययः । तेन आत्वं भूताः—आत्वेन वा भूताः, आकारान्ता इत्यर्थः । न लक्षणेन कृतात्मा इति विज्ञेयम् । अस्याप्ययमभिप्रायः—एजन्तानुकरणत्वे प्रमाणाभावात् प्रक्रियागौरवाच्च प्रयोग एव ये आकारान्ताः प्रयुज्यन्ते तदनुकरणानामयमेकशेषनिर्देशः । सामान्यानुकरणं वा 'दा' इति 'धा'इति पृथक् पदं निर्दिष्टमिति ॥

प्रणिदयत इति । घुसंज्ञायां 'नेर्गद्–' इति णत्वं भवति ॥

(उद्द्योतः) दाधाघ्व० ॥ २० ॥ दाधाशब्दयोरिति । प्रयोगस्थदाधारूपाणामेव सूत्रेऽनुकरणादिति भावः ॥

दोदेङ्धेटामेजन्तानामिति । एषां चात्र 'प्रकृतिवदनुकरणं भवति' इतिन्यायादशितीति प्रसज्यप्रतिषेधाश्रयणाच्चात्वमिति भावः ॥ अत्र च पक्षे लक्षणप्रतिपदोक्तपरिभाषानिरनुबन्धकपरिभाषादीनां न प्रवृत्तिः, सर्वेषां स्वरूपेणैवानुकृतत्वात् ॥ दारयतिधारयत्योश्च नातिप्रसङ्गः, तयोरनुकरणे आत्वासंभवेनेह द ध इत्यनयोरनुपात्तत्वात् ॥ दीङोऽपि नेह ग्रहणम्, एज्विषयाभावेन तदनुकरणे आत्वासंभवादिति बोध्यम् ॥

नन्वात्वभूतानामित्यस्य जातात्वानामित्यर्थे दाणादीनां संज्ञा न स्यात् निष्ठायाः पूर्वनिपातश्च स्यात्, अत आह—भवतेरिति । प्राप्तात्वानामित्यर्थः ॥ प्रमाणाभावादिति । प्रयोगार्थत्वाच्छास्त्रस्योपस्थितप्रयोगस्यानुकरणे संभवति अनुपस्थितैजन्तानुकरणे प्रमाणाभाव इत्यर्थः ॥ गौरवाच्चेति । दीङस्तु जादावात्वे कृते प्रणिदातेत्यत्र नेर्गदेति णत्वानापत्तेश्चेत्यपि बोध्यम् ॥ एकशेषस्य सर्वदाधारूपाणामानन्त्येन ज्ञानासंभवात् दुर्ज्ञेयत्वेऽप्याह—सामान्येति ॥ ननु समाहारद्वन्द्वे 'दाधं' इति स्यात्, अन्यत्र 'दाधौ' इति स्यादत आह—पृथक्पदमिति । अँसो रुत्वे यत्वे लोपे च निर्विसर्गं साधु ॥

(भाष्यम्)

भारद्वाजीयाः पठन्ति—

(१६४ भारद्वाजीयनाक्षेपकवार्तिकम् ॥ २ ॥)

॥ * ॥ घुसंज्ञायां प्रकृतिग्रहणं शिद्विकृतार्थम् ॥ * ॥

(भाष्यम्)

घुसंज्ञायां प्रकृतिग्रहणं क्रियते ।

किं प्रयोजनम् ?

शिदर्थं विकृतार्थं च । शित्युदाहृतम् । विकृतार्थं खल्वपि—प्रणिदाता, प्रणिधाता ।

किं पुनः कारणं न सिध्यति ?

'लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव' इति प्रतिपदं ये आत्वभूतास्तेषामेव स्यात्, लक्षणेन ये आत्वभूतास्तेषां न स्यात् ॥

(प्रदीपः) प्रणिदातेति । द्यतेर्देङो वा रूपम् । प्रणिधातेति-धेटः ॥ लक्षणेति । लाक्षणिके हि लक्षणानुसन्धानद्वारेण प्रतिपत्तिर्बहिरङ्गा, प्रतिपदोक्ते त्वन्तरङ्गा ॥

(उद्द्योतः) विकृतानां दोदद्घोरिति सूत्रे धेर्ङ्निवृत्त्यर्थदाग्रहणपर्यालोचनया वक्तुं सुलभमिति मत्वा वार्तिके 'शिदर्थम्' इत्युक्तम् । भारद्वाजीयैस्तु तावद्विवेकासमर्थान्प्रति विकृतार्थमित्यप्युक्तम् ॥ प्रणिदातेत्यादौ लाक्षणिकत्वं स्फुटयति—द्यतेर्देङो वेति ॥

(प्रकृतिग्रहणानन्वयबोधकं भाष्यम्)

अथ क्रियमाणेऽपि प्रकृतिग्रहणे कथमिदं विज्ञायते-दाधाः प्रकृतय इति, आहोस्विद्दाधां प्रकृतय इति ?

किं चातः ?

यदि विज्ञायते-दाधाः प्रकृतय इति, स एव दोषः—आत्वभूतानामेव स्यात्, अनात्वभूतानां न स्यात् ॥

अथ विज्ञायते-दाधां प्रकृतय इति, अनात्वभूतानामेव स्यात्, आत्वभूतानां न स्यात् ॥

(प्रदीपः) कथमिति । 'दाधाप्रकृतयः' इति षष्ठीसमासः–कर्मधारयो वा, उभयथाऽप्यव्याप्तिरिति प्रश्नः ॥

दाधाः प्रकृतय इति । 'दीयते' इत्यादावीत्वादेः ॥ आत्वभूतानामिति । दाण्दाग्धाधामाम् ॥

(उद्द्योतः) प्रकृतय इत्यस्य सापेक्षत्वादाह—ईत्वादेरिति ॥ दाणिति । 'आत्वभूताः' इत्यनेन उपदेशे आकारान्ता एवोच्यन्ते, तद्भिलक्षणास्त्वनात्वभूता इति भावः ॥

(प्रकृतिग्रहणान्वयबोधकं भाष्यम्)

एवं तर्हि नैवं विज्ञायते-दाधाः प्रकृतय इति, नापि दाधां प्रकृतय इति ।

कथं तर्हि ?

दा धा घुसंज्ञा भवन्ति, प्रकृतयश्चैषामिति ॥

(प्रदीपः) प्रकृतयश्चैषामिति । प्रत्यासत्त्या 'एषाम्' इति लभ्यते ॥

(उद्द्योतः) प्रत्यासत्त्येति । एवं च 'एषाम्' इति नापूर्वमिति भावः ॥ एतत्सामर्थ्यादेव लाक्षणिकानामप्यनुकरणमनुमास्यत इति तात्पर्यम् ॥

(प्रकृतिग्रहणोपसंहारभाष्यम्)

तत्तर्हि प्रकृतिग्रहणं कर्तव्यम् ?

(प्रकृतिग्रहणार्थस्य प्रकारान्तरेण साधकं भाष्यम्)

न कर्तव्यम् । इदं प्रकृतमर्थग्रहणमनुवर्तते ।
क प्रकृतम् ?
"ईदूतौ च सप्तम्यर्थे" इति । ततो वक्ष्यामि—
"दा धा घ्वदाप्" "अर्थे" इति ॥

(प्रदीपः) अर्थ इति । एतद्द्वितीयं वाक्यम् । सन्निधानाच्च दाधामर्थे यः प्रवर्तते स घुसंज्ञ इति प्रकृतीनामपि सिध्यति ॥

(उद्योतः) नन्वेकवाक्यत्वे दारयत्याद्येकदेशानर्थकव्यावृत्त्यर्थमेव तत्स्यात्, न त्वन्यरूपप्रापकमत आह—एतद्द्वितीयमिति ।

अर्थवत्परिभाषयैवानर्थकव्यावृत्तौ सिद्धायामर्थग्रहणानुवृत्तिर्वाक्यभेदार्थैवेति भावः ॥

(बाधकभाष्यम्)

नैवं शक्यम् । ददातिना समानार्थान् रातिरासतिदाशतिमंहतिप्रीणातिप्रभृतीनाहुः, एतेषामपि घुसंज्ञा प्राप्नोति । तस्मान्नैवं शक्यम् ॥
न चेदेवं, प्रकृतिग्रहणं कर्तव्यमेव ॥

(उद्योतः) भाष्ये—प्रीणातीति । यथा-पितृभ्यः प्रीणातीत्यादौ ॥

(प्रकारान्तरेण साधकं भाष्यम्)

न कर्तव्यम् । शिदर्थेन तावन्नार्थः । अवश्यं तत्र माङर्थं प्रकृतिग्रहणं कर्तव्यम् । प्रणिमयते प्रण्यमयते -इत्येवमर्थम्, तत् पुरस्तादपकक्ष्यते घुप्रकृतौ माप्रकृतौ चेति ॥

(प्रदीपः) तत्पुरस्तादिति । घुमाशब्दयोर्मध्ये प्रकृतिग्रहणं कर्तव्यं, तदुभाभ्यामपि सम्भन्त्स्यते ॥

(उद्योतः) ननु तत्रोभयान्वयाय प्रकृतिग्रहणद्वये कर्तव्येऽत्रैव करणं युक्तमत आह—तदुभाभ्यामिति । घुप्रकृतिमाशब्दानां द्वन्द्वे सन्निधानाविशेषादुभयप्रकृतिर्गृह्यते-इति प्रणिद्रयते प्रणिमयत इति उभयत्रापि णत्वं सिध्यतीत्यर्थः ॥

(आक्षेपभाष्यम्)

यदि प्रकृतिग्रहणं क्रियते, प्रनिमिनोति-प्रनिमीनाति-अत्रापि प्राप्नोति ॥

(प्रदीपः) प्रनिमिनोतीति । 'मीनातिमिनोतिदीङां ल्यपि च' इत्यात्त्वविधानाद्भवति माप्रकृतित्वमनयोः ॥

(उद्योतः) आत्त्वविधानादिति । एज्विषये इकारान्तानामात्त्वविधानादिति भावः ॥

(प्रतिबन्दीभाष्यम्)

अथाक्रियमाणेऽपि प्रकृतिग्रहणे इह कस्मान्न भवति-प्रनिमाता-प्रनिमातुं-प्रनिमातव्यमिति ?

(प्रतिबन्दीसमाधानभाष्यम्)

आकारान्तस्य ङितो ग्रहणं विज्ञायते ॥

(समाधानभाष्यम्)

यथैव तर्हि अक्रियमाणे प्रकृतिग्रहणे आकारान्तस्य ङितो ग्रहणं विज्ञायते, एवं क्रियमाणेऽपि प्रकृतिग्रहणे आकारान्तस्य ङितो ग्रहणं विज्ञास्यते ॥

(उद्योतः) भाष्ये—एवं क्रियमाणेऽपीति । णत्वविधौ माङ्स्यतीति निर्देष्टव्यमिति भावः ॥ यद्यपि लक्षणप्रतिपदोक्तपरिभाषया मीनातिमिनोत्यादेशानां ग्रहणाभावो वक्तुं शक्यस्तथापि मेङोऽग्रहणवारणाय गामादाग्रहणेष्वविशेष इत्युक्तेर्माग्रहणे तदप्रवृत्तिः । 'मा मौने' इत्यस्य योगे णत्ववारणाय च ङित्पाठ आवश्यक इति तात्पर्यम् ॥

(भारद्वाजीयप्रयोजननिराकरणभाष्यम्)

विकृतार्थेन चापि नार्थः । दोष एवैतस्याः परिभाषायाः-"लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव" इति-"गामादाग्रहणेष्वविशेषः" इति ॥

(प्रदीपः) गामादाग्रहणेष्विति । अस्य चार्थस्य दैपः पित्त्वं 'अदाप्' इति प्रतिषेधे सामान्यग्रहणार्थं लिङ्गम् । अन्यथाऽस्य लाक्षणिकत्वादत्र ग्रहणं न भविष्यतीति किं प्रतिषेधार्थेन पित्त्वेन ? सामान्यापेक्षया च 'निरनुबन्धकग्रहणे—' इति 'लक्षणप्रतिपदोक्तयोः—' इति च परिभाषाद्वयानुत्थानमिह ज्ञापयतीति धेटोऽपि सिध्यति । 'दो दद्घोः' इत्यत्र वा 'दः' इत्येतत् धेण्निवृत्त्यर्थं सत् धेटो घुसंज्ञां ज्ञापयति । न हि दधातिनिवृत्त्यर्थं द इत्येतत्, अस्य 'दधातेर्हिः' इति ह्यादेशविधानाद्द्भावाप्रसङ्गात् ॥

(उद्योतः) सामान्येति । एतत्सूत्रगृहीतदाधापेक्षया परिभाषागृहीतयोर्ऽप्यपेक्षया परिभाषाद्वयापेक्षया चेत्यर्थः ॥ निरनुबन्धकेति । स च 'दोऽवखण्डने' इत्ययम् ॥ धेटोऽपीति । अन्यथाऽस्य लाक्षणिकत्वाद् ग्रहणाप्रसक्तिः ॥ यत्तु सानुबन्धकत्वादिति । तन्न । निरनुबन्धकस्य 'धा' इत्यस्याप्रसिद्धत्वात् ॥ ये तु दाविषयमेव तज्ज्ञापकं मन्यन्ते, तन्मते धेडंशे ज्ञापकान्तरमाह—दो ददिति ॥

(यदागमन्यायाधिकरणम्)

(१६५ आक्षेपवार्तिकम् ॥ ३ ॥)

॥ * ॥ समानशब्दप्रतिषेधः ॥ * ॥

(भाष्यम्)

समानशब्दानां प्रतिषेधो वक्तव्यः । प्रनिदारयति, प्रनिधारयति । दा धा घुसंज्ञा भवन्तीति घुसंज्ञा प्राप्नोति ॥

(प्रदीपः) समानशब्दानामिति । समानश्रुतीनामित्यर्थः ॥ प्रनिदारयतीति । दृङ्धृङोर्णिचि वृद्धावाकारे कृते दाधाशब्दौ संपद्येते, तौ चार्थवन्तौ । पश्चात्तु रपरत्वं क्रियमाणमागमभूतत्वादन्यत्वं न करोतीति प्राप्तिः ॥

(उद्योतः) समानत्वं नार्थत इत्याह—श्रुतीनामिति ॥ तौ चेति । एतेनानर्थकत्वात्तयोर्घुत्वं नेत्यपास्तम् ॥ पश्चादिति । प्रणिदापयतीत्यत्र पुगिवेति भावः ॥ आगमभूतत्वात्—आगमस्वरूपत्वात् ॥

(१६६ समाधानवार्तिकम् ॥ ४ ॥)

॥ * ॥ समानशब्दाप्रतिषेधोऽर्थवद्ग्रहणात् ॥ * ॥

(भाष्यम्)

समानशब्दानामप्रतिषेधः, अनर्थकः प्रतिषेधोऽप्रतिषेधः ।

घुसंज्ञा कस्मान्न भवति ?

'अर्थवद्ग्रहणात्' । अर्थवतोर्दाधोर्ग्रहणम् । न चैतावर्थवन्तौ ॥

(प्रदीपः) अर्थवद्ग्रहणादिति । 'अर्थवद्ग्रहणे नानर्थकस्य' इत्यस्यार्थस्य 'स्वं रूपम्–'इत्यनेन ज्ञापितत्वात् । 'उरण् रपरः' इति चाण्विधीयमान एव रपरो भवतीति वृद्धिः क्रियमाणा रपरा भवतीति 'दार्' धातोरेवार्थवत्त्वं न तु तदवयवयोरिति नास्ति घुसंज्ञा ॥

(समाधानहेत्वन्तरभाष्यवार्तिकम् ॥)

अनुपसर्गाद्वा

(भाष्यम्)

अथवा यत्क्रियायुक्ताः प्रादयस्तं प्रति गत्युपसर्गसंज्ञा भवन्ति । न चैतौ दाधौ प्रति क्रियायोगः ॥

(प्रदीपः) अनुपसर्गाद्वेति । अभ्युपगम्य घुसंज्ञां दोषं परिहरति । घुसंज्ञापेक्षया यस्योपसर्गत्वं तस्मात् परस्य नेर्घौ परतो णत्वं विधीयते । अत्र दाधापेक्षया नास्ति प्रशब्दस्योपसर्गत्वम्, किंतु दार्धार्शब्दापेक्षयेत्यदोषः ॥

(उद्योतः) अभ्युपगम्येति । अदाविति प्रतिषेधार्थेन दैपः पित्त्वेन द्दो दद्दित्यनेन च परिभाषामात्रानुपस्थानज्ञापनसंभवादिति भावः ॥ किंत्विति । तयोरेव क्रियावाचित्वादिति भावः ॥

(आक्षेपभाष्यम्)

यद्येवम्, इहापि तर्हि न प्राप्नोति—प्रणिदापयति प्रणिधापयतीति । अत्रापि नैतौ दाधावर्थवन्तौ, नाप्येतौ दाधौ प्रति क्रियायोगः ॥

(प्रदीपः) इहापि तर्हीति । अत्रापि पुकि कृते पकारान्तोऽर्थवान्, न केवलो दाशब्दः । पुगन्तमेव च प्रत्युपसर्गत्वम्, न दाशब्दमिति प्रश्नः ॥

(१६७ समाधानवार्तिकम् ॥ ५ ॥)

॥ * ॥ न वाऽर्थवतो ह्यागमस्तद्गुणीभूतस्तद्ग्रहणेन गृह्यते यथाऽन्यत्र ॥ * ॥

(भाष्यम्)

न वा एप दोषः ।

किं कारणम् ?

अर्थवत आगमस्तद्गुणीभूतोऽर्थवद्ग्रहणेन गृह्यते ।

'यथाऽन्यत्र' । तद्यथा—अन्यत्रापि अर्थवत आगमोऽर्थवद्ग्रहणेन गृह्यते ।

क्वान्यत्र ?

लविता चिकीर्षितेति ।

(प्रदीपः) न वाऽर्थवत इति । लब्धात्मकस्य भावस्य निमित्तवशादुपचयापचयौ व्यपदेशहानिं न कुरुतः, यथा देवदत्तस्याङ्गाधिक्याङ्गच्छेदौ । इहाप्यन्तरङ्गत्वात् कृतायां दाधोर्घुसंज्ञायां पश्चादुत्पन्नः पुगागमो घुव्यपदेशं न निवर्तयति नाप्यर्थवत्त्वमित्यदोषः । अनर्थकस्याप्यागमो व्यपदेशहानिं न करोति, यथा सत्यपि रेफेऽकाराकारयोर्गुणवृद्धिव्यपदेशाहानिः । इह त्वर्थवतो ग्रहणादर्थवत इत्युक्तम् । यदा च प्रकृत्यर्थः प्रेण विशेष्यते तदाऽयं परिहारः, ण्यर्थविशेषणत्वे तु प्रस्य दाधौ प्रत्यनुपसर्गत्वाद् णत्वं न भवत्येव ॥ तद्गुणीभूत इति । प्रयोगसंपादन उपकारक इत्यर्थः ॥

(उद्योतः) भाष्ये तद्गुणीभूत इति । यमुद्दिश्यागमो विहितः स तद्गुणीभूतः शास्त्रेण तदवयवत्वेन बोधितोऽतस्तद्ग्रहणेन तद्ग्राहकेण तद्बोधकेन गृह्यते बोध्यते आगमविशिष्ट इति परिभाषार्थः । तदाह—लब्धात्मकस्येति ॥ तेन दार्धारोर्घ्योर्वृत्तिः सूचिता ॥ अपचय इति । दृष्टान्तार्थम् ॥ अन्तरङ्गत्वादिति । इदं यथोद्देशे, कार्यकाले तु णत्वदेशा संज्ञासिद्धा स्यादिति बोध्यम् ॥ वस्तुतः कार्यकालपक्षे पूर्वं पुकः प्रवृत्तावपि दापो दाशब्देन ग्रहणाद् घुत्वं सुलभमेवेति चिन्त्यम् ॥ घुव्यपदेशं न निवर्तयति नाप्यर्थवत्त्वमितीति । स्वविशिष्टे तयोरानयनादिति भावः ॥ अकाराकारयोरिति । रेफविशिष्टयोरित्यर्थः ॥ इह त्विति । घुसंज्ञासूत्रे इत्यर्थः ॥ अत्रेद बोध्यम् । अङ्गावयवाकारस्य मुग्विधायकानेमुगिति सूत्रारम्भसामर्थ्येन क्वचिद्वर्णग्रहणे नास्याः प्रवृत्तिः । तेन दिदीये इत्यादौ यणादिकं न । अयमेवार्थो भाष्येऽर्थवद्ग्रहणेन ध्वन्यत इत्याहुः ॥ प्रयोगेति । इदं चिन्त्यम् । आगमवत्प्रत्ययादेरपि प्रयोगसंपादने उपकारकत्वेन तेषामपि प्रकृतिग्रहणेन ग्रहणापत्तिर्मूलयुक्तेस्तुल्यत्वात् । अस्य मूलयुक्तित्वाभावे तु तत्कथनवैयर्थ्यापत्तिः । तस्मान्मदुक्तव्याख्यैव ज्यायसी ॥

(आदेशवादिनं आगमवादिनं प्रत्याक्षेपभाष्यम्)

युक्तं पुनर्यन्नित्येषु नाम शब्देष्वागमशासनं

स्यात् न नित्येषु नाम शब्देषु कूटस्थैरविचालिभिर्वर्णैर्भवितव्यमनपायोपजनविकारिभिः । आगमश्च नामापूर्वः शब्दोपजनः ? ॥

(प्रदीपः) **युक्तं पुनरिति** । ततश्च नित्येष्वागमविरोधात् तद्द्वारेणादेशविधानाद्दाप्शब्द एवार्थवान्न दाशब्द इति तदवस्थो दोष इति भावः ॥

(उद्द्योतः) भाष्ये **यन्नित्येष्विति** । वियदादिवद् वर्णप्रकृतिप्रत्ययपदवाक्यादिरूपाः सर्गाद्यकालिकोत्पत्तिमन्तः प्रलयकालिकनाशवन्तश्चेति पक्षे इति भावः ॥ **दाप्शब्द एवार्थवान्न दाशब्द इति** । स तु न दाशब्द इत्यर्थः । एवं च घुत्वाभावात्तदवस्थो दोष इति भावः ॥ श्रौतस्थानषष्ठ्यभावात्स्थानिवत्त्वस्य नैतद्विषये प्रवृत्तिरिति तात्पर्यम् ॥ कूटस्थत्वं व्याचष्टे—भाष्ये **अविचालिभिरिति** । तद्विवरणम**नपायेत्यादि** । द्वन्द्वान्मत्वर्थीये पश्चान्नञ्समासः ॥

(आगमवादिन आदेशवादिनं प्रत्याक्षेपभाष्यम्)

अथ युक्तं यन्नित्येषु शब्देष्वादेशाः स्युः ॥

(प्रदीपः) **अथ युक्तमिति** । तत्रापि स्थानिनमपनीयादेशः क्रियत इत्यनित्यत्वप्रसङ्गः । यश्चोभयोर्दोषो न तमेकश्चोद्यः॥

(उद्द्योतः) नन्वेतावतापि स्वपक्षास्थापनाद्वैतण्डिकत्वमस्य स्यादत आह—**यश्चेति** ॥

(आदेशवादिनः समाधानभाष्यम्)

बाढं युक्तम् । शब्दान्तरैरिह भवितव्यम् । तत्र शब्दान्तरे शब्दान्तरस्य प्रतिपत्तिर्युक्ता ॥

(प्रदीपः) **बाढमिति** । प्रसङ्गवाची स्थानशब्दो न निवृत्तिवाची, ततश्च सन्त एव प्रयोगे नित्याः शब्दा बुद्ध्युन्मज्जननिमज्जनद्वारेण प्रतिपाद्यन्ते । आगमस्त्ववस्थितस्यापूर्वः क्रियमाणो नित्यत्वं विरुणद्धि ॥

(उद्द्योतः) **प्रसङ्गवाचीति** । षष्ठी स्थान इत्यत्रत्यः । प्रसङ्गश्च बुद्धेरिति भावः ॥ **सन्त एव प्रयोगे नित्या इति** । आदेशरूपा इत्यर्थः ॥ बुद्ध्युन्मज्जननिमज्जने यथाक्रममादेशस्य स्थानिनश्च ॥ भाष्ये **शब्दान्तरे इति** । तद्बुद्धौ प्राप्तायामित्यर्थः ॥

(सिद्धान्तोपसंहारभाष्यम्)

आदेशास्तर्हीमे भविष्यन्ति अनागमकानां सागमकाः ॥

तत् कथम् ? ।

'सर्वे सर्वपदादेशा दाक्षीपुत्रस्य पाणिनेः ।
एकदेशविकारे हि नित्यत्वं नोपपद्यते' ॥

(प्रदीपः) **आदेशास्तर्हीमे इति** । इड् भवतीत्येतद्द्वारेण तव्यस्येतव्यादेशः क्रियते ॥ **सर्वे इति** । आगमा अपीत्यर्थः ॥ **सर्वपदादेशा इति** । पदशब्देन न सुप्तिङन्तं गृह्यतेऽपि तु कार्ये प्रतिपद्यमानं प्रतीयमानं प्रकृतिप्रत्ययादि तत् सर्वं पदम् ॥ **एकदेशविकारे हीति** । यद्यपि सर्वविकारेऽप्यनित्यत्वं यथा पिठरस्थस्य पयसः पाकादिषु, तथापि विकाराभावप्रतिपादनपरमेतत् । बुद्धिविपरिणाममात्रं स्थान्यादेशागमागमिभावद्वारेण क्रियत इत्यर्थः ॥ यद्येवं दाशब्दस्य दाप्शब्द आदेशः क्रियत इति दाशब्दस्यानर्थक्यप्रसङ्गः ॥ नैष दोषः । नित्यतासमर्थनायादेशपक्ष आश्रितः । प्रक्रियायां तु कल्पितायामागमागमिभाव एव । अन्यथागमादेशयोर्भेदेन व्यवहारो न स्यात् ॥

(उद्द्योतः) **आदेशास्तर्हीम इति** । इमे आगमत्वेन व्यवह्रियमाणा अपि तथा विधीयमाना अपि आदेशास्तत्सदृशा भविष्यन्तीत्यर्थः ॥ आद्यन्तावित्याद्येकवाक्यतया आर्धधातुकस्याद्यवयव इडित्यर्थे वृत्ते नित्यत्वानुपपत्तिमूलकवाक्यान्तरकल्पनेन केवलतव्यबुद्धौ प्रसक्तायामिकारादिः साधुरिति बोधः ॥ तेनात्रापि बुद्धिविपरिणाममात्रस्यैव सत्त्वेन न नित्यत्वहानिरिति भावः ॥ **यदागमा** इति न्यायस्य चात्रापि पक्षे सत्त्वात्प्रणिदापयतीत्यादौ न दोषः ॥ ये त्वत्र पक्षे आगमत्वं नास्त्येवेति वदन्ति, ते मान्याः । **अनागमकाना**मित्यादिव्यवहारासङ्गतेः । निरवयवकबुद्धिनिमज्जनसावयवकबुद्ध्युन्मज्जनेनागमव्यवहारस्यापि निर्बाधत्वात् । **तत्कथ**मिति प्रश्ने तुल्यन्यायत्वादाह—**सर्वे सर्वपदेति** । यथा **एरुरि**त्यादौ अवयवयोः श्रौतस्थान्यादेशभावेऽपि नित्यत्वानुपपत्तिमूलकः समुदाययोरपि स कल्प्यते, एवम् अवयवत्वेन विधानेऽपि अर्थापत्तिमूलकवाक्यान्तरकल्पनेन निरवयवसावयवबुद्ध्योर्विपरिणाममात्रेणादेशत्वव्यवहारो गौणो नित्यत्वरक्षणाय कल्प्यत इति । यथा च तत्र कल्प्यमानस्थान्यादेशभावेन श्रौतावयवस्थान्यादेशभावस्य न त्यागः, अत एवाचः परस्मिन्नित्यादीनामुक्तिसम्भवः । तथाऽत्रापि श्रौतावयवावयविभावस्य न त्याग इति **यदागमा** इत्येतत्प्रवृत्तिरव्याहतैवेति ईईशस्थान्यादेशभावे स्थानिवत्त्वस्य न प्रवृत्तिः, स्थानिवदितिश्रुतेः श्रौतस्थान्यादेशभावानुपपत्तिमूलकतया कल्प्य-

मानस्यान्यादेशभावके पुहरित्यादावेव तत्प्रवृत्तेः । नत्वत्र केवलानुमानिके । अत एव छावस्थायामछिति पक्षेऽडादिविशिष्टस्यापिबदित्यादौ न पिबाद्यादेश इति दिक् । तदेतदाह—इह्भवतीत्येतद्वारेणेति ॥ आगमा अपीत्यर्थ इत्यस्य तथेत्यादिः । अत एवाग्रे वक्ष्यति—'बुद्धिविपरिणाममात्रं स्यान्यादेशागमागमिभावद्वारेण क्रियते' इति ॥ एतेन 'आगमा अपि' इत्येवं सर्वपदव्याख्यायां 'एकदेशविकारे हि' इति वाक्यशेषविरोधः । आदेशस्योपपादिकाया विकारव्यापकीभूताभावप्रतियोगित्वरूपनित्यत्वानुपपत्तेः सकलपक्षाप्रवृत्तिरित्यादिरित्यपास्तम् ॥ पद्यमानमिति । कार्यवत्तया प्रतीयमानं प्रकृत्यादीत्यर्थः । सर्वपदेत्यत्र स्वार्थे कः । सर्वशब्दश्चात्रावयवकात्स्र्न्यवाची ॥ यद्येवमिति । एवं चैतदवयवस्यानर्थक्यान्न संज्ञा । पुकः पूर्वं 'दा' इत्यस्य तु न संज्ञा, कार्यकालपक्षे संज्ञाया णत्वदेशस्थत्वेन पुक्दृष्ट्याऽसिद्धत्वाँत् । न च पुग्विशिष्टस्य दाग्रहणेन ग्रहणम् । यदागमा इत्यस्याभावात् । पूर्वोक्तरीत्या स्थानिवत्त्वाप्रवृत्तेश्चेति भावः ॥ आदेशपक्ष इति । बुद्धिविपरिणामपक्ष इत्यर्थः ॥ कल्पितप्रक्रियादशायां तु न कल्पितागमत्वादिव्यवहारत्याग इति यदागमा इत्यादेः सत्त्वेनात्रापि पक्षे न दोष इति भावः ॥

(समाधानभाष्यम्)

न वक्तव्यः ॥

(आक्षेपभाष्यम्)

घुसंज्ञा कस्मान्न भवति ?

(सिद्धान्तिनः समाधानभाष्यम्)

"सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य" इत्येवं न भविष्यति ॥

(प्रदीपः) **सन्निपातेति** । अकित्त्वसन्निपातेनात्वं क्रियते । यदि चात्र घुसंज्ञा स्यात् 'स्थाघ्वोरिच्च' इति कित्त्वं स्यादित्यकित्त्वस्य व्याघातः स्यादिति घुसंज्ञां प्रति नैवाकार आत्मानं दर्शयतीति घुसंज्ञा न प्रवर्तते ॥ अत्र केचिदाहुः—दीङस्तुजादावात्वे कृते घुसंज्ञा भवत्येवेति प्रणिदातेति णत्वं भवति । अत एव वार्तिककारेण 'स्थाघ्वोरित्त्वे' इति विषयविशेषो निर्दिष्टः ॥ **अन्ये त्वाहुः**—निर्देश एवैजन्तानामनुकरणानामात्वे कृते दाण्दाम्धाञां चैकशेषे द्वन्द्वे च 'दाधा' इति निर्देशाद्दीङो नास्ति प्राप्तिः । न हि तदनुकरणस्यात्त्वमस्ति, अगुणविषयत्वात् ॥

(उद्द्योतः) **अकित्त्वेति** । एचो विषयस्यान्यथाऽसंभवादिति भावः ॥ **कित्त्वमिति** । तदभावे संनियोगशिष्टत्वादित्त्वमपि नेति कार्याभावाद् घुत्वस्याप्रवृत्तिरिति भावः ॥ **प्रणिदातेति** । ननु 'प्रणिदीयते' इत्यत्र नित्यणत्वप्रसङ्गः, णत्वविधौ प्रकृतिग्रहणात्—इति चेन्न, इष्टापत्तेः ॥ **अन्ये त्वाहुरिति** । अत्राऽरुचिबीजं तु—वार्तिकभाष्यविरोधाद् न तथा सूत्रतात्पर्यमिति ॥ **अगुणेति** । गुणनिमित्तप्रत्ययप्रसङ्गाभावादित्यर्थः ॥

(इति सन्निपातन्यायाधिकरणम्)

(नानुबन्धकृतमनेजन्तत्वन्यायाधिकरणम्)

(१६९ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ दाप्प्रतिषेधे न दैप्यनेजन्तत्वात् ॥ * ॥

(भाष्यम्)

दाप्प्रतिषेधे दैपि प्रतिषेधो न प्राप्नोति—अवदातं मुखम् ।

ननु चाऽऽत्त्वे कृते भविष्यति ।

तस्यात्त्वं न प्राप्नोति ॥

किं कारणम् ?

अनेजन्तत्वात् ॥

(प्रदीपः) **दाप्प्रतिषेध इति** । 'दाप् लवने' इत्यस्यैव निषेधः स्यादित्यर्थः ॥ **अवदातमिति** । तत्त्वमत्र प्राप्नोति ॥

(उद्द्योतः) **इत्यस्यैवेति** । न तु दैप इत्यर्थः । तस्य पकारे श्रूयमाणे आत्वायोगादिति भावः ॥ ननु पकारे लुप्तेऽपि कथमात्वम् ? उपदेशकाले एजन्तत्वाभावात्, नानुबन्धकृतमित्याद्याश्रयणे तु प्रकृतेऽपि न दोष इति चेन्न । उपदेश इति षष्ठ्यर्थे सप्तम्याः सत्त्वेनोपदिश्यमानस्यैजन्तस्येत्यर्थेन लुप्ते आत्त्वप्रवृत्तेः । सति तु तस्मिन् नात्त्वम्, एजन्तत्वाभावात् यस्मात्परो नास्ति तत्रैवान्तशब्दप्रवृत्तेरिति दिक् ॥ **तत्त्वमिति** । अच उपसर्गात्त इत्यनेनेत्यर्थः ॥

(१७० समाधानवार्तिकम् ॥ २ ॥)

॥ * ॥ सिद्धमनुबन्धस्याऽनेकान्तत्वात् ॥ * ॥

(भाष्यम्)

सिद्धमेतत् ।

कथम् ?

अनुबन्धस्यानेकान्तत्वात् । अनेकान्ता ह्यनुबन्धाः ॥

(उद्द्योतः) **भाष्ये—अनेकान्ता इति** । एवं च पकारसत्त्वेऽपि एजन्तत्वानपायादात्त्वप्रवृत्तिरिति भावः ॥

(समाधानान्तरभाष्यवार्तिकम् ॥)

पित्प्रतिषेधाद्वा ।

(भाष्यम्)

अथवा "दाधा घ्वपित्" इति वक्ष्यामि । तच्चाऽवश्यं वक्तव्यम् । अदाविति ह्युच्यमाने इहापि प्रसज्येत-प्रणिदापयतीति ॥

(आवश्यकतानिराकरणभाष्यम्)

शक्यं तावदनेनादाविति ब्रुवता वान्तस्य प्रतिषेधो विज्ञातुम् ॥

(प्रदीपः) शक्यं तावदिति । दैंप्दैपौ धातुषु वान्तौ पठितव्यौ ॥

(उद्द्योतः) तच्चावश्यमित्यादि विघटयितुं भाष्ये शक्यं तावदिति । लक्षणप्रतिपदोक्तपरिभाषया तु पुनरन्तेऽदाविति निषेधो न शक्यो वारयितुं गामादाग्रहणेऽविशेषाद् । दावित्यपि पकारोपलक्षितदाग्रहणमेवेति भावः । वान्तपक्षेऽपि चर्त्वेन पस्य सिद्धत्वान्नास्ति सूत्रभेदः ॥

(आक्षेपभाष्यम्)

सूत्रं तर्हि भिद्यते ॥

(सिद्धान्तिभाष्यम्)

यथान्यासमेवास्तु ॥

(आक्षेपसारणभाष्यम्)

ननु चोक्तम् "*दाप्प्रतिषेधे न दैपि*" इति ॥

(परिहारसारणभाष्यम्)

परिहृतमेतत् "*सिद्धमनुबन्धस्यानेकान्तत्वात्*" इति ॥

(आक्षेपभाष्यम्)

अथैकान्तेषु दोष एव ॥

(समाधानभाष्यम्)

एकान्तेष्वपि न दोषः । आत्त्वे कृते भविष्यति ॥

(समाधानानुपपत्तिभाष्यम्)

ननु चोक्तम्—'तत्रात्वं न प्राप्नोति, किं कारणम् । अनेजन्तत्वाद्—' इति ॥

(समाधानोपपत्तिभाष्यम्)

एकारलोपे कृते भविष्यति ॥

(आक्षेपभाष्यम्)

नष्टयं तदा दाप् भवति ॥

(उद्द्योतः) शङ्कते—नष्टयमिति ॥

(समाधानभाष्यम्)

भूतपूर्वगत्या भविष्यति ॥

(उद्द्योतः) उत्तरयति—भूतपूर्वेति । दात्वं श्रुत्या, पकारवैशिष्ट्यं तु अनयेति भावः ॥

(समाधानसाधकभाष्यम्)

एतच्चात्र युक्तम्—यत्सर्वेष्वेव सानुबन्धकग्रहणेषु भूतपूर्वगतिर्विज्ञायते॥ अनैमित्तिको ह्यनुबन्धलोपस्तावत्येव भवति ॥

(प्रदीपः) तावत्येवेति । इत्संज्ञायां सत्यामेव प्रयोगे दाशब्द एवायं पित्कार्यं तु लभत इत्यर्थः ॥

(उद्द्योतः) इत्संज्ञायामिति । उपदेशोत्तरकालं जाताया-मेवेत्यर्थः ॥

(समाधानान्तरभाष्यम्)

अथ वाऽऽचार्यप्रवृत्तिर्ज्ञापयति-'नानुबन्धकृतमनेजन्तत्वम्' इति । यदयम् "उदीचां माङो व्यतीहारे" इति मेङः सानुबन्धकस्याऽऽत्त्वभूतस्य ग्रहणं करोति ॥

(प्रदीपः) अथवेति । अनुबन्धानामेकान्तत्वपक्षे उपदेश एवैजन्तानामात्त्वमुच्यमानं दैपो न प्राप्नोतीति ज्ञापकोपन्यासः ॥ **माङ इति** । मेङो ग्रहणं न माङः, मेङो व्यतिहारेण नित्ययोगात् । माङ्स्तु विवक्षावशाद् व्यतिमिमीत इति कादाचित्कत्वाद् व्यतिहारयोगस्य । अैणिदानं व्यतिहार इत्येकोऽर्थः । उदीचां मेङ इति तु न कृतम् । एवं हि 'नानुबन्धकृतमनेजन्तत्वम्' इति न ज्ञापितं स्यात् ॥

(उद्द्योतः) मेङ इति । अन्तरङ्गत्वाद्व्यतीहारो नित्यसंबन्ध एव गृह्यते; न तु पदान्तरसन्निधानेन बहिरङ्गव्यतीहारवृत्तिरिति भावः ॥ केचित्तु माङोऽनभिधानात्तत्वाप्रत्ययानुत्पत्तिरिति न तस्य ग्रहणमित्याहुः ॥ उदीचां मेङ इति । उदीचां म इत्यस्याप्युपलक्षणमिदम् । न चानुबन्धसत्त्वे मे इत्यस्य धातुत्वाभावात्कथमात्वम्, अनुबन्धलोपे एव धातुत्वमित्यर्थस्य 'न धातुलोप' सूत्रे भाष्यकैयटयोः स्पष्टत्वादिति वाच्यम् । आत्वविधायके धातोरित्यस्यासंबन्धाद् । गवादिशब्दानामुपदेशाभावान्नात्वम् । रैप्रभृतीनामुपदेशेऽपि तेषामशित्परत्वाभावाद् नात्वम् । प्रसज्यप्रतिषेधेऽपि प्रत्यासत्त्या शित्प्रत्ययपरत्वयोग्यानामेजन्तानामेव ग्रहणान्न दोष इति दिक् ॥

(समाधानान्तरभाष्यम्)

अथ वा दाबेवायम् । न दैबस्ति ॥

कथम्—'अव दायति' इति ? ॥

श्यन्विकरणो भविष्यति ॥ दाधाध्वदाप् ॥ १९ ॥

(प्रदीपः) **अथवेति** । दिवादिषु **दापृशोधने** इति पठिष्यत इत्यर्थः ॥ १९ ॥

(उद्द्योतः) **दिवादिष्विति** । ननु ताच्छीलिके चानशि दायमान इत्यत्र स्वरे भेदः श्यनि धातोर्युदात्तत्वं, शपि चानशोऽन्तोदात्तत्वमिति चेन्न । सतिशिष्टादपि विकरणस्वरात् सार्वधातुकस्वरस्य बलीयस्त्वोक्तेरुभयथाऽप्यन्तोदात्तत्वानपायादिति दिक् ॥ १९ ॥

(२० अतिदेशसूत्रम् ॥ १ । १ । ५ आ. ९ ॥)

आद्यन्तवदेकस्मिन् ॥ १ । १ । २१ ॥

(प्रदीपः) **आद्यन्तवदेक०** ॥२१॥ एकशब्दोऽसहायवाची, न संख्यावाची । बहुष्वपि व्यवस्थितस्यैकत्वसंख्याऽस्तीति किं 'एकस्मिन्' इत्यनेन कृतं स्यात् । 'एकस्मिन्' इत्युपमेये सप्तमीनिर्देशात् 'आद्यन्तवत्' इत्युपमानात् सप्तम्यन्ताद्वतिर्विज्ञायते । यथा—मथुरावत् पाटलिपुत्रे प्राकार इति । द्वयोर्ह्युपमानोपमेययोराधाराधेयसंबन्धप्रतिपादनाय वाक्यं प्रयुज्यते । यदि च तयोर्भिन्नविभक्तिकत्वं स्यात्, उपमानोपमेयभाव एव न गम्येत ॥ सर्वातिदेशानां कार्यातिदेशस्य प्राधान्यात्तस्यैवेहाश्रयणम् ॥

(उद्द्योतः) **आद्यन्तव०** ॥२१॥ **बहुष्वपीति** । यद्युत्तरा सङ्ख्या पूर्वसङ्ख्याबाधिका, तथापीतरेषां बुद्धिविषयत्वामात्रे बहुमध्यस्थेऽप्येकत्वाङ्गीकाराच्च दोषः । यथा शते पञ्चाशदितीति भावः ॥ **किमेकस्मिन्नित्यनेनेति** । तद्धि समासंनयने भव इत्यर्थे आकारस्यादित्वे तस्य वृद्धत्वेन प्राप्तछाभावार्थं दरिद्रातेरिवर्णान्तलक्षणाचोऽभावार्थं च । अत्र च स्वरे विशेषः ॥ उपमेये सप्तमीसत्त्वे सप्तम्यन्ताद्वतौ मानमाह—**द्वयोरिति** ॥ **उपमानोपमेययोरिति** । प्राकारपदवाच्येनेति शेषः ॥ **आधाराधेयसंबन्धेति** । आधारत्वाधेयत्वरूपसंबन्धप्रतिपादनायेत्यर्थः ॥ **न गम्येतेति** । उपमानप्रकारकोपमेयविशेष्यकबोधे समानविभक्तिकत्वस्य तन्त्रत्वादिति भावः ॥ **सर्वातिदेशानामिति** । रूप–निमित्त–तादात्म्य–शास्त्र–व्यपदेश–कार्यातिदेशानां मध्ये इत्यर्थः ॥ **प्राधान्यादिति** । सर्वेषां कार्यार्थत्वादिति भावः ॥

(सूत्रप्रयोजनाधिकरणम्)

(प्रयोजनाक्षेपभाष्यम्)

किमर्थमिदमुच्यते ?

(प्रदीपः) **किमर्थमिति** । व्यपदेशिवद्भावेनैव सिद्धत्वान्न कर्तव्यमित्यर्थः ॥

(१७१ प्रयोजनवार्तिकम् ॥ १ ॥)

॥ * ॥ सत्यन्यस्मिन्नाद्यन्तवद्भावादेकस्मिन्नाद्यन्तवद्वचनम् ॥ * ॥

(भाष्यम्)

सत्यन्यस्मिन् यस्मात् पूर्वं नास्ति परमस्ति स आदिः-इत्युच्यते । सत्यन्यस्मिन् यस्मात् परं नास्ति पूर्वमस्ति सोऽन्तः-इत्युच्यते । सत्यन्यस्मिन्नाद्यन्तवद्भावादेतस्मात् कारणात् एकस्मिन्नाद्यन्तापदिष्टानि कार्याणि न सिध्यन्ति, इष्यते च स्युरिति । तान्यन्तरेण यत्नं न सिध्यन्ति-इति एकस्मिन्नाद्यन्तवद्वचनम् । एवमर्थमिदमुच्यते ॥

(प्रदीपः) इतरो मुख्ये संभवति गौणे न स्यादित्याह—**सत्यन्यस्मिन्निति** । आद्यन्तौ विद्येते यस्मिन् शास्त्रे तद्—आद्यन्तवत्, तस्य भावात्—प्रवर्तनादित्यर्थः । क्वचित् **'आद्यन्तभावात्'** इति पाठः ॥

(उद्द्योतः) **मुख्ये**—व्यपदेशिनि । **गौणे**—व्यपदेशिसदृशे ॥ नन्वाद्यन्तवद्भावादिति न वतिः, सत्यन्यस्मिन्मुख्याद्यन्तत्वात् । नापि मतुप्, आद्यन्तशब्दवच्छास्त्रसद्भावस्य पैरपूर्वसत्त्वानपेक्षत्वेन सत्यन्यस्मिन्नित्यस्यायोगादत आह—**आद्यन्ताविति** । आद्यन्तशब्दावित्यर्थः । एवं चाद्यन्तवद्भावादित्यस्याद्यन्तपदवच्छास्त्रप्रवृत्तेरित्यर्थः ॥ **क्वचिदिति** । आद्यन्तव्यवहारादिति तदर्थः ॥

(आक्षेपभाष्यम्)

अस्ति प्रयोजनमेतत् ? ॥

(समाधानभाष्यम्)

किं तर्हीति ॥

(१८४ आक्षेपवार्तिकं प्रथमखण्डम् ॥ २ ॥)

॥ * ॥ तत्र व्यपदेशिवद्वचनम् ॥ * ॥

(भाष्यम्)

तत्र व्यपदेशिवद्भावो वक्तव्यः । व्यपदेशिवदेकस्मिन् कार्यं भवतीति वक्तव्यम् ॥

(प्रदीपः) **तत्र व्यपदेशिवद्वचनमिति** । सर्वकार्यसिद्ध्यथ व्यापकं कर्तव्यमित्यर्थः ॥ तत्र निमित्तसद्भावान्मुख्यो व्यपदेशो यस्यास्ति स व्यपदेशी यस्तु व्यपदेशहेत्वभावादविद्यमानव्यपदेशः स तेन तुल्यं वर्तते कार्यं प्रतीति व्यपदेशिवद्भवतीत्युच्यते ॥

(उद्द्योतः) **सर्वकार्येति** । आद्यन्तापदिष्टाद्यन्तानपदिष्टसर्वकार्यसिद्ध्यर्थं गुर्वपि **व्यपदेशिवदिति** आद्यन्तवदित्यस्य स्थाने कार्यमिति भावः ॥ **स तेनेति** । तेन तुल्यमिति तृतीयायां सर्वविभक्त्यर्थान्तर्भावात्तृतीयान्ताद्वतिरुक्त इति बोध्यम् ॥

(भाष्यम्)

किं प्रयोजनम् ? ।

(१८४(प्रयोजनवार्तिकं द्वितीयखण्डम्)॥ ३ ॥)

॥ * ॥ एकाचोद्वेप्रथमार्थम् ॥ * ॥

(भाष्यम्)

वक्ष्यति-'*एकाचोद्वेप्रथमस्येति बहुव्रीहिनिर्देशः*-इति । तस्मिन् क्रियमाणे इहैव स्यात्— पपाच पपाठ; इयाय आर इत्यत्र न स्यात् । व्यपदेशिवदेकस्मिन् कार्यं भवतीत्यत्रापि सिद्धं भवति ॥

(उद्योतः) भाष्ये तस्मिन्क्रियमाण इति । तस्मिन्नाश्रीयमाण इत्यर्थः ॥ पपाचेति ॥ नन्वत्र धातुरेव प्रथम एकाज्, न तु धातोः प्रथम एकाजिति कथमत्र व्यपदेशिवद्भावं विना प्राप्तिरिति चेन्न । आदित्वपर्यायप्रथमत्वस्य सूत्रेणैवातिदेशसिध्या तत्र व्यपदेशिवद्भावारम्भस्य मुख्यं प्रयोजनमित्याशयात् । इयायेत्यादौ तु द्विर्वचनेऽचीति रूपस्थानिवत्त्वादज्व्यतिरिक्ताभावेन नैकाच्त्वमिति बोध्यम् ॥

(१८४(प्रयोजनवार्तिकं तृतीयखण्डम्)॥ ४ ॥)

॥ * ॥ षत्वे चाऽऽदेशसंप्रत्ययार्थम् ॥ * ॥

(भाष्यम्)

वक्ष्यति-'आदेशप्रत्यययोरित्यवयवषष्ठ्येषा-' इति । एतस्मिन् क्रियमाणे इहैव स्यात्-करिष्यति हरिष्यति, इह न स्यात् '[इन्द्रो मा] वक्षत् (ऋ० १।१२५।४)' 'स देवान्यक्षत् (ऋ० ३।४।२)' इति । व्यपदेशिवदेकस्मिन् कार्यं भवतीत्यत्रापि सिद्धं भवति ॥

(प्रदीपः) वक्षदिति । वच् लेट् तिप् इतश्च लोप इतीकारलोपः, लेटोऽडाटावित्यडागमः सिप् कुत्वम् । अत्र सकारमात्रं प्रत्ययो न तु प्रत्ययस्यावयवः सकार इति षत्वं न स्यात् ॥

(उद्योतः) भाष्ये—अवयवषष्ठयेवेति। प्रत्ययांशे इति भावः॥ एतस्मिन्क्रियमाणे इति । अवयवषष्ठीत्वे आश्रीयमाणे इत्यर्थः ॥

(आक्षेपोपसंहारभाष्यम्)

स तर्हि व्यपदेशिवद्भावो वक्तव्यः ? ॥

(सिद्धान्तिसमाधानभाष्यम्)

न वक्तव्यः ॥

(१८५ समाधानवार्तिकम् ॥ ५ ॥)

॥ * ॥ अवचनाल्लोकविज्ञानात् सिद्धम् ॥ * ॥

(भाष्यम्)

अन्तरेणैव वचनं लोकविज्ञानात् सिद्धमेतत् ॥

(प्रदीपः) अवचनादिति । अवचनं वचनरहितं यल्लोकविज्ञानं तस्माल्लोकव्यवहारादित्यर्थः । इदं तावदियायेति [य] इण्धातुः प्रयोगभेदाद्बहुरूपः—एति इतः यन्ति अयनम् आयकः अगात् गमयतीति । तस्यायमेकोऽजवयव इव लक्ष्यते । अथवा अर्थवतो धातोरयं वर्णरूप एकोऽजित्यर्थस्य त्यागोपादानाभ्यां भवति व्यपदेश एकाजिति । एवं शिलापुत्रकस्य शरीरमित्यनेकक्रियाविषयस्याऽवस्थातुरिदमेकावस्थायुक्तं शरीरमित्यस्ति व्यपदेशः । एवं सिप्प्रत्यय इट्सहितोऽपि दृष्टो जोषिषदित्यादौ, वक्षदित्यादौ केवलोऽपीति, तस्यायं सकार इति व्यपदिश्यते । लोकनिरूढश्चायं व्यवहार इति लोकवच्छास्त्रेऽपि व्यवहाराद्गौणमुख्यन्यायोऽत्र नावतरति ॥

(उद्योतः) विज्ञानशब्दो व्यवहारवाचीत्याह—व्यवहारादिति ॥ तत्फलितव्याख्यानं भाष्ये अन्तरेणैवेति । यथा लोके व्यवहारो वचनं विनैव सिध्यति तथा शास्त्रेपि वचनं विना सिध्यतीत्यर्थः ॥ अगादित्यादि । 'इणो गा लुङि' 'णौ गमिरबोधने' इत्यादेशौ । एकोच् असहायोऽजित्यर्थः ॥ नन्वेकाचोऽवयविनो द्विर्वचनमिति यस्यायमवयवस्तस्य बहुरूपस्य भवितव्यं द्वित्वेनेत्यत आह—अथवेति ॥ काल्पनिकभेदेन व्यवहारे दृष्टान्तमाह—एवमिति ॥ व्यपदेशो भेदनिबन्धनसंबन्धव्यवहारः ॥ शास्त्रेपीति । लोकाप्रसिद्धत्वमेव तत्त्यागे बीजं तच्च न प्रकृते इति भावः ॥

(एकदेशिदृष्टान्तभाष्यम्)

तद्यथा—लोके—'शालासमुदायो ग्रामः'—इत्युच्यते । भवति चैतदेकस्मिन्नपि—"एकशालो ग्रामः"—इति ॥

(उक्तदृष्टान्तविघटनभाष्यम्)

विषम उपन्यासः । ग्रामशब्दोऽयं बह्वर्थः । अस्त्येव शालासमुदाये वर्तते । तद्यथा—'ग्रामो दग्धः' इति ॥

अस्ति वाटपरिक्षेपे वर्तते । तद्यथा—'ग्रामं प्रविष्टः'—इति ॥

अस्ति च मनुष्येषु वर्तते । तद्यथा—'ग्रामो गतो ग्राम आगतः'—इति ॥

अस्ति सारण्यके ससीमके सस्थण्डिलके वर्तते । तद्यथा—'ग्रामो लब्धः'—इति ॥

तद्यः सारण्यके ससीमके सस्थण्डिलके वर्तते, तमभिसमीक्ष्यैतत्प्रयुज्यते-'एकशालो ग्रामः'इति ॥

(एकदेशिदृष्टान्तान्तरभाष्यम्)

यथा तर्हि—'वर्णसमुदायः पदम्' 'पदसमुदाय ऋक्,' 'ऋक्समुदायः सूक्तम्' इत्युच्यते । भवति चैतदेकस्मिन्नपि—'एकवर्णं पदम्,' 'एकपदा ऋक्,' 'एकर्चं सूक्तम्' इति ॥

(प्रदीपः) पदसमुदाय इति । पादपर्यायः पदशब्दः । तथा चैकपदा ऋगिति पाद एव विवक्षितः । न तु ऋचः कस्याश्चिदप्येकमेव पदं भवति ॥

(उद्योतः) पादपर्याय इति । वर्णसमुदायः पदमित्यत्र तु पदशब्दो यथाश्रुत एव ॥

(दृष्टान्तान्तरविघटनभाष्यम्)

अत्राप्यर्थेन युक्तो व्यपदेशः ।

पदं नाम-अर्थः, ऋक् नाम-अर्थः, सूक्तं नाम-अर्थः ॥

(प्रदीपः) **अत्राप्यर्थेनेति** । पदादीनां योऽर्थः सोऽन्यपदार्थ इत्यर्थः । अभेदोपचाराच्चार्थ एव पदादिभिरभिधीयते ॥

(उद्योतः) पदादीनामिति । 'एकवर्णं पदं' इत्यादौ ॥ ननु अर्थस्य पदत्व कथमत आह—अभेदेति । तदुपचारश्च शब्दार्थयोरनादिरिति बोध्यम् ॥ पदादिभिः—पदशब्दादिभिः ॥

(सिद्धान्तिनो दृष्टान्तभाष्यम्)

यथा तर्हि बहुषु पुत्रेष्वेतदुपपन्नं भवति-अयं मे ज्येष्ठः, अयं मे मध्यमः, अयं मे कनीयानिति । भवति चैतदेकस्मिन्नपि-अयमेव मे ज्येष्ठः, अयमेव मे मध्यमः, अयमेव मे कनीयान्-इति ॥

(प्रदीपः) **अयमेव मे ज्येष्ठ इति** । प्रथमरूपताऽध्यवसायात् । मध्यमकार्यकरणाच्च **'मध्यमः'** इति व्यपदिश्यते । अन्यो न जनितेति बुद्ध्या **'कनीयान्'** इति व्यपदिश्यते ॥

(उद्योतः) प्रथमेति । तस्मात्पूर्वस्याभावादिति भावः ॥ मध्यमकार्य—तत्संबन्धजसुखादिकम् ॥

(सिद्धान्तिनो द्वितीयदृष्टान्तभाष्यम्)

तथा-असूतायामसोष्यमाणायां च भवति—प्रथमगर्भेण हता-इति ॥

(प्रदीपः) **असूतायामिति** । बहुकृत्वोऽपि प्रसूता प्रथमपुत्रेण काचिद्धन्यते, तथा याऽपि प्रसोष्यते साऽपि काचित्पूर्वोत्पन्नेन पुत्रेण हन्यत इत्युभयोरुपादानम् । नापि प्रसूता नापि प्रसोष्यते कुक्षिस्थेनैव गर्भेण हता-प्रथमगर्भेण हतेति व्यपदेशः । अपत्यपर्यायो गर्भशब्दः । तस्या एव योग्यताऽध्यवसायेन भाविगर्भापेक्षया 'प्रथमगर्भेण हता' इति व्यपदिश्यते । स्यन्तरेषु वा बहुपुत्रत्वे सति आद्यगर्भस्य प्रथमव्यपदेशदर्शनात् तथाविधस्य प्रथमगर्भव्यपदेशः ॥

(उद्योतः) **बहुकृत्वोऽपीति** । यथा परशुरामेण रेणुका ॥ **तथा येति** । संप्रति गर्भिणीत्यर्थः । गर्भस्यमादाय तत्रापि प्रथमव्यवहार इत्यर्थः ॥ ननु या सृता सा न गर्भेण हता भवति किं त्वपत्येनेति गर्भेण हतायां तद्व्यतिरेकप्रदर्शनमयुक्तमत आह—**अपत्यपर्याय इति** । तच्चोदरस्थं-बहिर्भूतं वेत्यन्यत् ॥ तत्र प्रथमव्यवहारे बीजमाह—**तस्या एवेति** । स्त्र्यन्तरेषु-बहुप्रसववतीषु ॥ **तथाविधस्येति** । अविद्यमानपूर्वगर्भस्येत्यर्थः ॥

(सिद्धान्तिनस्तृतीयदृष्टान्तभाष्यम्)

तथा-अनेत्यानाजिगमिषुराह-इदं मे प्रथममागमनम्-इति ॥

(प्रदीपः) **अनेत्येति** । बहुकृत्वो ह्यागतः पूर्वमागमनं स्मृत्वा प्रथमव्यपदेशं तत्र मुख्यं करोत्येव, आजिगमिषुश्च भाव्यागमनानि बुद्ध्या व्यवस्थाप्य कुर्यादेव प्रथमव्यवहारम् । यस्तु सकृदेवागतः सोऽपि करोति प्रथमव्यवहारमिति प्रतिपादनार्थं 'अनेत्यानाजिगमिषुः' इत्युपात्तम् । तत्रान्यसंबन्धिषु बहुष्वागमनेष्वाद्यस्य प्रथमव्यवहारदर्शनात् तथाविधत्वात् एकस्मिन्नप्यागमने प्रथमव्यवहारः ॥

(उद्योतः) नन्वागमनं विना 'इदं मे प्रथममागमनं' इति व्यवहारासंभवात् अनेत्येदं मे प्रथममागमनमित्यसङ्गतमत आह—**बहुकृत्व इति** । अनेत्येत्यस्येतः पूर्वमिति शेष इति भावः ॥ **तथाविधत्वादिति** । अविद्यमानपूर्वागमनत्वादित्यर्थः ॥

(सूत्रप्रत्याख्याने वार्तिकावतरणभाष्यम्)

आद्यन्तवद्भावश्च शक्योऽवक्तुम् ॥

कथम् ?

(उद्योतः) परे तु पदऋगादिपदानि अर्थशब्दसमुदायवृत्तीनि, तस्य शब्दमात्ररूपवर्णपादऋगाद्यवयव इत्येव भाष्यार्थः । न तु शुद्धोऽर्थोऽन्यपदार्थ इति, तथाऽप्रतीतेः । 'एकर्चं सूक्तं पठ' इत्यादिव्यवहारानापत्तेश्च । एवं चार्थवतो धातोरयमेकोऽज् वर्णरूप [इति अर्थस्य त्यागोपादानाभ्यां भवति व्यपदेश एकाजिति] इति कैयटोक्तं चिन्त्यम् । एतद्भाष्यरीत्या तस्य मुख्यव्यवहारत्वेन व्यपदेशिवद्भावाविषयत्वात् । कैयटरीत्या शुद्धार्थस्यान्यपदार्थत्वेऽपि तथैवास्तु, शब्दार्थयोरभेदाच्च शब्देऽपि तत्त्वमिति अत्रापि न व्यपदेशिवद्भावप्रयोजनम् । [किं चैकाजिति बहुव्रीहिणा प्रथमस्येत्युपस्थितावयवस्य विशेषणम् । तस्य चानेर्थकत्वमिति अर्थस्योपादानत्यागावत्यसंबद्धौ । एतदेव ध्वनयता पदं नामार्थ इति भाष्ये उक्तम् । धात्ववयवत्वं तु कैयटोक्तरीत्या वक्तुं शक्यम् । अत एव बहुव्रीहिनिर्देशानुपपत्तिरेव व्यपदेशिवदित्याश्रयणे बीजमुक्तम् ॥] 'अत्राप्यर्थेन' इति भाष्यस्य—पदादिशब्दार्थस्यार्थेन युक्तत्वादित्यर्थः ॥ अर्थशब्दोभयवृत्तिपदत्वऋक्त्वादीत्याशयः ॥ पदं नामार्थ इत्यादेः—अर्थोऽपीत्यर्थः ॥ यथा तर्हीति । यथैकस्मिंस्तत्तद्धर्मारोपेण युगपज्ज्येष्ठत्वादिव्यवहारस्तथैकस्मिन्नारोपितानेकावस्थाभिः समुदायरूपत्वस्याप्यारोपेणैकाच्त्वादिव्यवहारोपपत्तिः । द्वितीये तृतीये च दृष्टान्ते प्रथमेत्युपलक्षणं चरमस्यापि । तृतीये कदाचिच्चरममागमनमित्यपि व्यवहारात् । आद्यन्तवद्भावश्च शक्योऽवक्तुमित्यस्य प्रकारान्तरेणापीति शेष इत्याहुः ॥ [वस्तुतस्तु ईदृशेषु पातञ्जलोक्तं विकल्पात्मकं वस्तुशून्यमेव ज्ञानमिति आरोपानुपयोग एव । लोकव्यवहारवत्तेनापि शास्त्रीयो व्यवहार इति तत्त्वम् ॥]

(१७३ प्रत्याख्यानसाधकवार्तिकम् ॥ ४ ॥)

॥ * ॥ अपूर्वानुत्तरलक्षणत्वादाद्यन्तयोः सिद्धमेकस्मिन् ॥ * ॥

(भाष्यम्)

अपूर्वलक्षण आदिः, अनुत्तरलक्षणोऽन्तः, एतच्चैकस्मिन्नपि भवति । अपूर्वानुत्तरलक्षणत्वात्-एतस्मात् कारणात् एकस्मिन्नप्याद्यन्तापदिष्टानि

कार्याणि भविष्यन्ति । नार्थ आद्यन्तवद्भावेन ॥

(प्रदीपः) इदानीं योगं प्रत्याख्यातुमाह—**अपूर्वेति** ॥ यद्यपि बहुष्ववस्थितेषु आद्यन्तशब्दौ प्रयुज्येते, तथाऽप्यपूर्वानुत्तरत्वमात्रमेतयोः प्रवृत्तिनिमित्तम् । तच्चैकस्मिन्नप्यस्तीति नार्थः सूत्रेण ॥

(प्रत्याख्यानासंभवभाष्यम्)

गोनर्दीयस्त्वाह—सत्यमेतत्, 'सति त्वन्यस्मिन्' इति ॥

(प्रदीपः) भाष्यकारस्त्वाह—**सति त्वन्यस्मिन्निति** । न ह्यनपेक्षितप्रतियोगिनोराद्यन्तयोः प्रवृत्तिरित्यर्थः । तस्मादेकस्मिन्मुख्य आद्यन्तव्यपदेशो नास्तीति कर्तव्यो योगः ॥ यद्यपि लौकिकेन व्यपदेशिवद्भावेनाद्यन्तव्यपदेश एकस्मिन्नपि सिध्यति, तथापि गौणत्वात्कार्येण न भवितव्यमिति यस्य भ्रान्तिः स्यात्तं प्रति योगोऽयमारब्धः ॥

(उद्द्योतः) गोनर्दीयपदं व्याचष्टे—**भाष्यकार इति** ॥ अनपेक्षितप्रतियोगिनोः—अनपेक्षितपरपूर्वयोः, **आद्यन्तयोः**—आद्यन्तरूपार्थयोः, प्रवृत्तिः—आद्यन्तशब्दप्रवृत्तिरित्यर्थः ॥ तथापीति । वस्तुतो लोकनिरूढत्वाद् गौणत्वमेवात्र नास्तीत्यर्थः ॥

(सूत्रप्रयोजनाधिकरणम्)

(प्रयोजनजिज्ञासाभाष्यम्)

कानि पुनरस्य योगस्य प्रयोजनानि ?

(१७४ प्रयोजनवार्तिकम् ॥ १ ॥)

॥ * ॥ आदिवत्त्वे प्रयोजनं—प्रत्ययञ्नितद्याद्युदात्तत्वे ॥ * ॥

(भाष्यम्)

प्रत्ययस्यादिरुदात्तो भवतीति, इहैव स्यात्—कर्तव्यं, तैत्तिरीयः । औपगवः-कापटवः-इत्यत्र न स्यात् ॥

"ञ्नित्यादिर्नित्यम्" इति, इहैव स्यात्—अहिचुम्बकायनिः, आग्निवेश्यः । गार्ग्यः-कृतिरित्यत्र न स्यात् ॥

(प्रदीपः) **प्रत्ययञ्नितद्याद्युदात्तत्व इति** । प्रत्ययस्याद्युदात्तत्वं ञ्निति चाद्युदात्तत्वमित्यर्थः ॥ कथं पुनर्भिन्नविभक्त्योर्द्वन्द्वः ? उच्यते—प्रत्ययस्य यदाद्युदात्तत्वं तस्य प्रत्ययोऽपि विषय इति प्रत्ययेऽपि तदुच्यते । यद्वा—ञ्निति यदाद्युदात्तत्वं तत् ञ्नितोऽपि संबन्धि भवतीति नास्ति भिन्नविभक्तित्वम् ॥ **'ऋदोरप्'** इत्याद्युदात्तत्वनिवृत्त्यर्थात्पित्त्वाल्लिङ्गादेकाचोऽपि प्रत्ययस्याद्युदात्तत्वं भविष्यतीति चेत्, अकारविषयमेव लिङ्गं स्यादीकारोकारयोः प्रत्यययोराद्युदात्तत्वं न स्यात् । विशेषणार्थं वा पित्करणं स्यात् थाथादिसूत्रे इत्यज्ञापकं स्यात् ॥

गार्ग्य इति । अत्र परत्वात् **'यस्य-'** इति लोपे कृत आदित्वाभावात्प्रकृतेराद्युदात्तत्वं न प्राप्नोति । स्वरविधौ स्थानिवद्भावप्रतिषेधाच्च नास्ति ग्यन्त्वम् । स्वरविधौ व्यञ्जनस्याऽविद्यमानत्वान्नास्ति हलपेक्षमप्यादित्वम् ॥ **कृतिरिति** । क्तिनो नित्त्वं **'तादौ च निति कृत्यतौ'** इत्येवमर्थं स्यात् । **'सौचर्यः सप्तम्यस्तदन्तसप्तम्यः'** इत्यनाश्रित्यैतदुक्तम् ॥

(उद्द्योतः) कथमिति । भिन्नविभक्त्यन्तयोरसमप्रधानत्वेन साहित्याप्रतीतेरित्यर्थः ॥ **इकारोकारयोरिति** । 'उपाधिः' 'चिकीर्षुः' इत्यादौ ॥ सामान्यापेक्षज्ञापकत्वेऽप्याह—**विशेषणार्थं वेति** ॥

अहिचुम्बकारप्राचामवृद्धादिति फिन् । अग्निवेशाद्गर्गादियञ् ॥ **स्वरविधाविति** । नन्वस्य स्वरोद्देश्यके विधावित्यर्थो वा- हलः स्वरप्राप्तावित्यर्थो वा । उभयथाऽपि नेह प्राप्तिरिति चेत् । सत्यम्, अत्र सूत्रेऽनन्तरापेक्षमेवादित्वं गृह्यते । अन्त्यस्याच एव तद्भावलंभत्वेनोपस्थितत्वादिति भाष्याशयात् । किं च सैणमित्यादावाद्युदात्तत्वं न स्यादिति दोषः । क्तित्त्वं तु वृद्ध्यर्थतया सावकाशं बोध्यम् ॥ **क्तिन इति** । अनेकाज्भ्यस्तु चिरिजिर्यादिभ्योऽनभिधानात् क्तिनभाव इति भावः ॥ ननु तदन्तसप्तमीत्वे गार्ग्यादौ समुदाये मुख्य एवादिः संभवतीति न दोष इत्यत आह—**सौचर्य इति** ॥

(प्रयोजनभाष्यवार्तिकम् ॥)

वलादेरार्धधातुकस्येट् प्रयोजनम् ॥

(भाष्यम्)

"आर्धधातुकस्येड्वलादेः" इति, इहैव स्यात्-करिष्यति, हरिष्यति । जोषिषत् (ऋ० २।३५।१) मन्दिषदित्यत्र न स्यात् ॥

(प्रदीपः) **जोषिषदिति** । लेट् । **'इट ईटि'** इति च ज्ञापकं सिज्विषयमेव स्यादिति सिप इण्न स्यात् ॥

(उद्द्योतः) लेडिति । **'सिब्बहुलं लेटि'** इति सिप् ॥ इट ईटीति । न च यमरमनमामित्यत्र वलादेरित्यस्य संबन्धे फलाभावात्कथमेतज्ज्ञापकम् । रुदादिभ्य इति सूत्रे वलादेरित्यस्य संबन्धसत्त्वेन मध्येऽपि संबन्धस्यैव न्याय्यत्वात् । अत एव सप्तमे (७।२।३) भाष्ये—"एकाचस्तौ वलीति च" इत्युक्तम् ॥

(प्रयोजनभाष्यवार्तिकम् ॥)

यस्मिन्विधिस्तदादित्वे प्रयोजनम् ॥

(भाष्यम्)

वक्ष्यति-'यस्मिन्विधिस्तदादावल्ग्रहणे' इति । तस्मिन् क्रियमाणे "अचि श्नुधातुभ्रुवां य्वोरियङुवङौ" इहैव स्यात्-श्रियः-भ्रुवः । श्रियौ-भ्रुवौ-इत्यत्र न स्यात् ॥

(प्रदीपः) **यस्मिन्विधिरिति** । 'स्वस्य च रूपस्य' इति नानुवर्तते-इति प्रयोजनत्वेनोपन्यासः ॥

(प्रयोजनभाष्यवार्तिकम् ॥)

अजाद्याद्त्वे प्रयोजनम् ॥

(भाष्यम्)

"आडजादीनाम्" इहैव स्यात्—ऐक्षिष्ट, ऐहिष्ट। अध्यैष्ट-इत्यत्र न स्यात् ॥

(प्रदीपः) अजाद्याद्त्व इति। सूत्रपाठापेक्षया प्रयोजनोपन्यासः । वार्तिककारस्तु—'अजादीनामटा सिद्धम्' इत्याह ॥

(अन्तवत्त्वप्रयोजनजिज्ञासाभाष्यम्)

अथान्तवत्त्वे कानि प्रयोजनानि?

(प्रयोजनभाष्यवार्तिकम् ॥)

अन्तवद्द्विवचनान्तप्रगृह्यत्वे प्रयोजनम् ॥

(भाष्यम्)

"ईदूदेद्द्विवचनं प्रगृह्यम्" इहैव स्यात्-पचेते इति, पचेथे इति। खट्वे इति, माले इति-इत्यत्र न स्यात् ॥

(प्रदीपः) अन्तवदिति। *येन विधिस्तदन्तत्वे* इत्यनेन गते प्रपञ्चार्थोऽयमुपन्यासः ॥

(उद्द्योतः) येन विधिरिति। तेनैव ईदूदेद्द्विवचनमित्यत्र तदन्तविधिरिति भावः ॥

(प्रयोजनभाष्यवार्तिकम् ॥)

मिदचोऽन्त्यात्परः प्रयोजनम् ॥

(भाष्यम्)

इहैव स्यात्—कुण्डानि-वनानि । तानि-यानि -इत्यत्र न स्यात् ॥

(प्रयोजनभाष्यवार्तिकम् ॥)

अचोऽन्त्यादि टि प्रयोजनम् ॥

(भाष्यम्)

"टित आत्मनेपदानां टेरे" इति, इहैव स्यात्—कुर्वाते, कुर्वाथे। कुरुते-कुर्वे-इत्यत्र न स्यात् ॥

(प्रदीपः) कुरुत इति। अर्थवता व्यपदेशिवद्भावात् तशब्दाकारस्यानर्थकत्वादिह प्रयोजनोपन्यासः ॥

(उद्द्योतः) अर्थवतेति। तत्र सार्थस्य त्यागोपादानाभ्यां भेदः सुकर इति भावः। इदं चिन्त्यम्, 'यद्यपि व्यपदेशिवद्भावेन सिध्यति तथापि गौणत्वान्नेति यस्य भ्रान्तिस्तं प्रति सूत्रारम्भः' इति पूर्वग्रन्थविरोधात्, सूत्रकारेण तदज्ञानात् तदुदाहरणसंभवाच्च। अर्थवतेति चासहायत्वस्यैवोपलक्षणम, ससहायस्य प्रायेणानर्थकत्वात्। तशब्दाकारश्चासहाय एव, येन सहायेनाचामन्तत्वस्य बहुव्रीह्यर्थस्य चोपपत्तिस्तादृशसहायाभावात्। अन्यथाऽऽद्यन्तवद्भावोऽपि न स्यात्। विजातीयकन्यादिसहायसत्त्वेऽप्येकपुत्रस्यायमेव ज्येष्ठ इत्यादिव्यवहाराद् ईदृशस्थलेऽपि लोकसिद्धत्वमित्याहुः ॥

(प्रयोजनभाष्यवार्तिकम् ॥)

अलोऽन्त्यस्य प्रयोजनम् ॥

(भाष्यम्)

"अतो दीर्घो यञि सुपि च" इहैव स्यात्—पटाभ्यां, घटाभ्याम्। आभ्यां-इत्यत्र न स्यात् ॥

(प्रदीपः) आभ्यामिति। अत्र द्वे अन्तवत्त्वे उपयुज्येते। अकारान्तस्यालोऽन्त्यस्य दीर्घत्वं भवतीति पृथक् प्रयोजनोपन्यासः ॥

(प्रयोजनभाष्यवार्तिकम् ॥)

येन विधिस्तदन्तत्वे प्रयोजनम् ॥

(भाष्यम्)

"अचो यत्" इहैव स्यात्—चेयम्, जेयम्। एयम्-अध्येयम्-इत्यत्र न स्यात् ॥

आद्यन्तवदेकस्मिन् कार्यं भवतीति अत्रापि सिद्धं भवति ॥ २१ ॥

(प्रदीपः) एयमिति। इणो रूपम्। इणस्तु 'इत्यं' इति भवति ॥ २१ ॥

(उद्द्योतः) इत्यमिति। एतिस्तुशास्विति क्यपो विधानादित्यर्थः ॥ २१ ॥

(२१ घसंज्ञासूत्रम् ॥ १।१।५ आ. १०)

तरप्तमपौ घः ॥ १ । १ । २२ ॥

(औपदेशिकग्रहणाधिकरणम्)

(प्रदीपः) तरप्तमपौ ॥२२॥ अतिशायनिकप्रकरण एव 'तापौ घः' 'पितौ घः' इति वा वक्तव्ये प्रकरणोत्कर्षेण संज्ञाकरणं—'स्वार्थेऽपि तरबस्ति' इति सूचनार्थम्। तेन 'अल्पाच्तरम्' इत्यादि सिद्धं भवतीत्याहुः ॥

(उद्द्योतः) तरप्त०॥२२॥ प्रकरणोत्कर्षेणेति। प्रकरणे—संज्ञाप्रकरणे उत्कर्षेण-गुरुभूतन्यासेनेत्यर्थः ॥ स्वार्थे इति। अनातिशायनिकस्यापि संज्ञाविधानार्थमत्र सूत्रम्। स चानिर्दिष्टार्थत्वात्स्वार्थे। तस्य संज्ञाफलं च 'उच्चैरेव-उच्चैस्तराम्' इत्यादौ किमेत्तिङव्ययघादित्याम्सिद्धिरिति भावः ॥ इत्याहुरिति। अत्रारुचिबीजं तु भाष्यानुक्तिः ॥

(१७५ आक्षेपवार्तिकम् ॥ १ ॥)

॥*॥ घसंज्ञायां नदीतरे प्रतिषेधः ॥*॥

(भाष्यम्)

घसंज्ञायां नदीतरे प्रतिषेधो वक्तव्यः। नद्यास्तरो नदीतरः-इति ॥

(प्रदीपः) नदीतर इति। तरतेः 'ऋदोरप्' इत्यप्। सर्वत्र चानुबन्धाः स्मर्यमाणा एव कार्यं प्रति हेतुत्वं लभन्त इति घसंज्ञाप्राप्तिः। साहचर्यं चेह व्यवस्थाहेतुः सर्वत्र नाश्रीयते। तथा हि 'द्वित्रिश्चतुरिति कृत्वोर्थे' इति कृत्वोर्थग्रहणं चतुरशब्दविशेषणार्थं कृतम्। अन्यथा द्वित्रिशब्दसाहचर्याच्चतुरशब्दोऽपि

क्त्वोर्थ एव प्रहिष्यत इति किं क्त्वोर्थग्रहणेन ॥

(उद्द्योतः) ननु नायं तरबित्यत आह— सर्वत्र चेति ॥ ननु तमप्साहचर्यात्तद्धित एव तरो ग्रहीष्यते इति नास्त्यबन्धे तरे प्रसक्तिरत आह—साहचर्यमिति । प्रत्ययाप्रत्यययोरिति परिभाषाऽपि नाश्रितेति बोध्यम् ॥ इह-शास्त्रे ॥

(१७६ समाधानवार्तिकम् ॥ २ ॥)

॥*॥ घसंज्ञायां नदीतरेऽप्रतिषेधः ॥*॥

(भाष्यम्)

घसंज्ञायां नदीतरेऽप्रतिषेधः । अनर्थकः प्रतिषेधोऽप्रतिषेधः । नद्यास्तरः- नदीतरः ॥

(प्रदीपः) **अप्रतिषेध इति** । न प्रतिषेधः—इति प्रतिषेधनक्रिया नञा निषिध्यते । भाष्यकारस्तु वस्त्वर्थं व्याचष्टे—'अनर्थकः प्रतिषेधः' इति ॥

(उद्द्योतः) वस्त्वर्थमिति । तात्पर्यार्थमित्यर्थः । असंदेह इतिवत् प्रतिषेधस्याभाव इत्यर्थको नञ्समासः ॥ एवं च 'अनर्थकः' इति भाष्योक्तेर्मध्यमपदलोपी समास इति न भ्रमितव्यमिति भावः ॥

(दोषस्मारकभाष्यम्)

घसंज्ञा कस्मान्न भवति ?

(दोषवारकं भाष्यवार्तिकम्)

तरप्ग्रहणं औपदेशिकम् ॥

(भाष्यम्)

औपदेशिकस्य तरपो ग्रहणम् । न चैष उपदेशे तरप्शब्दः ॥

(प्रदीपः) **औपदेशिकमिति** । उपदेशः प्रयोजनमस्य, तत्र वा भवं-औपदेशिकम् ॥

(उद्द्योतः) तरप्ग्रहणं—तरप्शब्दः, औपदेशिकं-उपदेशप्रयोजक इत्यर्थो भाष्यस्य । तदाह—उपदेशः प्रयोजनमिति । प्रयोजक इत्यर्थः ॥ न चैष उपदेशे तरप्शब्द इति भाष्यस्वरसादाह—तत्र वा भव इति । 'उपदेशे' इति भाष्ये 'भवः' इति शेषः ॥

(आक्षेपभाष्यम्)

किं वक्तव्यमेतत् ?

(समाधानभाष्यम्)

न हि ॥

(आक्षेपभाष्यम्)

कथमनुच्यमानं गंस्यते ?

(सिद्धान्तिसमाधानभाष्यम्)

इह हि व्याकरणे सर्वेष्वेव सानुबन्धकग्रहणेषु रूपमाश्रीयते—यत्रास्यैतद्रूपमिति । रूपनिर्ग्रहश्च शब्दस्य नान्तरेण लौकिकं प्रयोगम् । तस्मिंश्च लौकिके प्रयोगे सानुबन्धकानां प्रयोगो नास्तीति कृत्वा द्वितीयः प्रयोग उपास्यते ॥

कोऽसौ ?

उपदेशो नाम । न चैष उपदेशे तरप्शब्दः ॥

(प्रदीपः) **यत्रास्येति** । अनुबन्धयुक्तमित्यर्थः ॥ **न चैष इति** । काल्पनिकमस्य तरप्त्वं, न तु साक्षान्निर्दिष्टम् ॥

(उद्द्योतः) सर्वेष्वेव सानुबन्धकग्रहणेष्विति भाष्यं प्रकृताभिप्रायं, शब्दमात्रग्रहणेऽपि स्वं रूपमित्यनेन रूपाश्रयणादिति बोध्यम् ॥ यत्रास्येति । यत्रास्यैतद्रूपं तत्र घसंज्ञेत्यर्थः ॥ एवं चोपदेश एव घसंज्ञा । प्रयोगे तु स्थानिवद्भावेन सेति बोध्यम् ॥ काल्पनिकमिति । ऋदोरबितिसूत्रपर्यालोचनावगतत्वेनानुमानिकमित्यर्थः ॥

(घसंज्ञाभ्युपगमेऽपि दोषाभावप्रदर्शकभाष्यम्)

अथवा—अस्त्वस्य घसंज्ञा ॥

को दोषः ?

(दोषदर्शनभाष्यम्)

घादिषु नद्या ह्रस्वो भवतीति ह्रस्वत्वं प्रसज्येत ॥

(समाधानभाष्यम्)

समानाधिकरणेषु घादिष्वित्येवं तत् ॥

(प्रदीपः) **समानाधिकरणेष्विति** । आतिशायनिकश्च स्वार्थिकत्वात् समानाधिकरणः ॥

(उद्द्योतः) स्वार्थिकत्वात्-प्रकृत्यभिहितद्योतकत्वात्, समानाधिकरणः-प्रकृत्या समानविषय इत्यर्थः । सामानाधिकरण्यं चैकविशेष्यकबोधजनकत्वमिति बोध्यम् ॥

(आक्षेपभाष्यम्)

यदा तर्हि सैव नदी, स एव तरः, तदा प्राप्नोति ॥

(प्रदीपः) **यदा तर्हीति** । ननु 'तीर्णिः' इति भवितव्यम् । एवं तर्हि 'तीर्यत इति-तरः' इति सामान्येन पदं संस्क्रियते, पश्चात्तया विशेष्यते इति न दोषः ॥

(उद्द्योतः) ननु तीर्णिरिति । ऋतः परस्य क्तिनो निष्ठावद्वचनान्नत्वम् ॥ सामान्येनेति । अनिर्धारितकर्मविशेषेणेत्यर्थः । अत एव पुंस्त्वम्, घञजपः पुंसीत्युक्तेः ॥

(समाधानभाष्यम्)

स्त्रीलिङ्गेषु घादिष्वेवं तत् । अवश्यं चैतदेवं विज्ञेयम् । समानाधिकरणेषु घादिष्वित्युच्यमाने इह प्रसज्येत—महिषी रूपमिव, ब्राह्मणी रूपमिवेति ॥ २२ ॥

(प्रदीपः) **स्त्रीलिङ्गेष्विति** । स्वार्थिकश्च प्रकृतिलिङ्गानुविधानात् स्त्रीलिङ्गः ॥ **महिषी रूपमिवेति** । इवशब्दो भिन्नक्रमः । तेनायमर्थः-महिषीवेयमाकृतिरिति । तत्र 'सुप्सुपा' इति समासे कृते ह्रस्वत्वं स्यात् ॥ २२ ॥

(उद्द्योतः) महिषी रूपमिवेति । नन्विदमसमस्तं-समस्तं वा । नाद्यः, उत्तरपदाधिकाराद्रूपशब्दस्य चातथात्वादप्राप्तेः । किं च रूपशब्देनाकृत्यभिधानात्कस्याकृतिरिव महिषीति साकाङ्क्षं स्यात् । नान्त्यः, षष्ठीतत्पुरुषे वैयधिकरण्याद्धस्वाप्राप्तेः । विशेषणसमासे तु पूर्वनिपातवैपरीत्यापत्तिः । तस्मादुपमागर्भसमासस्य विग्रहवाक्यमिदम् । स च समासो नोपमानानि सामान्यवचनैरित्यनेन, रूपशब्दस्योपमेयवाचकत्वेऽपि साधारणधर्मावाचकत्वात् । साधारणधर्मो ह्यत्र विसंष्ठुलत्वादिः । नाप्युपमितं व्याघ्रादिभिरिति, रूपशब्दस्योपमेयवाचित्वेन पूर्वनिपातवैपरीत्यापत्तेः । तस्योपमानवाचित्वे तु

कस्य रूपमिति विशेषणस्य गापेक्षत्वाद्वृत्तिर्न स्यादत आह—इव-शब्द इति। सुप्सुपेति च ॥ ह्रस्वत्वं स्यादिति। अप्रत्ययो-ऽपि घत्वे तत्साहचर्याद्रूपादेरप्रत्ययस्यापि ग्रहणं स्यादिति भावः ॥ यद्यपि रूपमित्युक्ते कस्य रूपमिति अस्त्याकाङ्क्षा तथापि प्रधानस्य साकाङ्क्षत्वान्न दोषः ॥ २२ ॥

(२२ संख्यासंज्ञासूत्रम् ॥ १ । १ । ५ आ. ११)

बहुगणवतुडति संख्या ॥ १।१।२३ ॥

(लोकप्रसिद्धसंख्यावाचिनां संख्यात्वसाधनाधिकरणम्)

(१७७ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ संख्यासंज्ञायां संख्याग्रहणं संख्यासंप्रत्ययार्थम् ॥ * ॥

(भाष्यम्)

संख्यासंज्ञायां संख्याग्रहणं कर्तव्यम्। बहुगण-वतुडतयः संख्यासंज्ञा भवन्ति, संख्या च संख्या-संज्ञा भवतीति वक्तव्यम्।

किं प्रयोजनम्?

'संख्यासंप्रत्ययार्थम्'। एकादिकायाः संख्यायाः संख्याप्रदेशेषु संख्या-इत्येष संप्रत्ययो यथा स्यात् ॥

(प्रदीपः) बहुगणवतुडति० ॥ २३ ॥ संख्या-संप्रत्ययार्थमिति । संख्याया एकादिकायाः संख्याप्रदेशेषु संप्रत्ययार्थमित्यर्थः ॥

(उद्द्योतः) बहुगण० ॥ २३ ॥ संख्यात्वेन संप्रत्ययस्य लोकत एव सिद्धेराह—एकादिकाया इति। संख्यासंप्रत्ययेति वार्तिके सङ्ख्येति संप्रत्यय इत्यर्थः। एकादिकायाः सङ्ख्यायाः सङ्ख्याप्रदेशेष्विति शेषपूरणं बोध्यम् ॥ सङ्ख्येत्येष इति भाष्यस्य सङ्ख्येत्येतच्छब्दाभिन्न इत्यर्थः। 'शब्दार्थप्रत्ययानामितरेत-राध्यासात्संकरः' इति पातञ्जलसूत्रात्। एतच्च पातञ्जलसूत्रवृत्ता-वुपपादितमस्माभिः। 'नारद इत्यबोधि' इत्यादावप्येवमेव। एवं च कर्मत्वाप्रसक्तिरेव॥ 'सङ्ख्याशब्दजन्यः' इत्यर्थे 'सङ्ख्येत्याकारकः' इत्यर्थे च 'एष'शब्दान्वयानुपपत्तिस्तदुपादानवैयर्थ्यं चेति बोध्यम् ॥

(आक्षेपबाधकभाष्यम्)

ननु चैकादिका संख्या लोके संख्या-इति प्रतीता, तेनास्याः संख्याप्रदेशेषु संख्यासंप्रत्ययो भविष्यति ॥

(प्रदीपः) ननु चेति । यथा-पशुः-अपत्यं-देवता-इति लौकिकोऽर्थो गृह्यते, तथैकादिकाऽपि संख्या ग्रहीष्यत इत्यर्थः ॥

(उद्द्योतः) सङ्ख्या ग्रहीष्यत इति। सूत्रं त्वधिकसंग्र-हार्थमिति भावः ॥

(आक्षेपसाधकभाष्यम्)

एवमपि कर्तव्यम् ॥

(१७८ आक्षेपसाधकवार्तिकम् ॥ १ ॥)

॥ * ॥ इतरथा ह्यसंप्रत्ययोऽकृत्रि-मत्वाद्यथा लोके ॥ * ॥

(भाष्यम्)

अक्रियमाणे हि संख्याग्रहणे एकादिकायाः संख्यायाः संख्येत्येष संप्रत्ययो न स्यात्।

किं कारणम्?

'अकृत्रिमत्वात्'। बह्वादीनां कृत्रिमा संज्ञा। कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसंप्रत्ययो भवति ॥

'यथा लोके'। तद्यथा-'गोपालकमानय' 'कट-जकमानय' इति यस्यैषा संज्ञा भवति स आनीयते, न यो गाः पालयति, यो वा कटे जातः ॥

(प्रदीपः) कृत्रिमाकृत्रिमयोरिति । न्यायोऽयम्। तथाहि-सर्वार्थाभिधानशक्तियुक्तः शब्दो यदा विशिष्टेऽर्थे व्यवहा-राय नियम्यते तदा तत्रैव प्रतीतिं जनयति, नान्यत्र ॥

(उद्द्योतः) न्यायोऽयमिति। अभ्यासाम्रेडितादिसंज्ञाविषये चैतन्न्यायोपयोगो द्रष्टव्यः ॥ नियम्यते इति। सर्वार्थबोधकत्वेऽपि लोके तत्रैव गृहीतशक्तिकतयाऽन्यत्र शक्त्यग्रहणे चाधिकसंग्रहार्थं-त्वादगृहीतशक्तिग्राहकत्वाचास्य नियमत्वं चिन्त्यम्। न्यायबीजं तु प्रकरणं-इति भाष्य एव स्फुटीभविष्यति ॥

(आक्षेपभाष्यम्)

यदि तर्हि कृत्रिमाकृत्रिमयोः कृत्रिमे संप्रत्ययो भवति, "नदीपौर्णमास्याग्रहायणीभ्यः" अत्रापि प्रसज्येत ॥

(प्रदीपः) नदीपौर्णमासीति। 'यू स्त्र्याख्यौ नदी' इति संज्ञाविधानात् संज्ञिनो ग्रहणं प्राप्तं न तु स्वरूपस्य, 'अशब्द-संज्ञा' इति निषेधात् ॥

(समाधानभाष्यम्)

पौर्णमास्याग्रहायणीग्रहणसामर्थ्यान्न भविष्यति ॥

(प्रदीपः) पौर्णमासीति। नियमार्थं पौर्णमास्याग्रहा-यणीग्रहणमीकारान्तानां स्यादिति चेत्, एवमपि 'ऊपौर्णमास्या-ग्रहायणीभ्यः' इति वक्तव्यं स्यात्। ऊकारग्रहणेन च नदीसंज्ञ-कमेवोकारान्तं पौर्णमास्याग्रहायणीशब्दसाहचर्यात् ग्रहीष्यते ॥

(उद्द्योतः) नियमार्थमिति। नियमश्च सामान्यविषय एव न कालवाचिविषयः, व्याख्यानात्। अतो गौर्यादन्तेऽपि न दोषः ॥ नन्वनदीसंज्ञकेभ्योऽपि खलप्वादिभ्य ऊकारान्तेभ्यः स्यादत आह—ऊकारग्रहणेनेति। वस्तुतस्तु दोषग्रस्तनियमापेक्षया नदीशब्दे कृत्रिमाकृत्रिमन्यायबाधज्ञापनमेव उपायः ॥

(आक्षेपभाष्यम्)

तद्विशेषेभ्यस्तर्हि प्राप्नोति—गङ्गा-यमुनेति ॥

(प्रदीपः) तद्विशेषेभ्य इति। गङ्गादिभ्यः ॥

(उद्योतः) भाष्ये-तद्विशेषेभ्यस्त्विति प्रासङ्गिकी शङ्का, तां व्याचष्टे— गङ्गादिभ्य इति । अपगङ्गं परियमुनमित्युदाहरणे । अत्र हि टचि अन्तोदात्तत्वम् । तदभावे परिप्रत्युपापावर्ज्यमानाहोरात्रावयवेष्विति पूर्वपदप्रकृतिस्वरत्वमित्याहुः ॥

(समाधानभाष्यम्)

अत्राप्याचार्यप्रवृत्तिर्ज्ञापयति-'तद्विशेषेभ्यो न भवति' इति । यदयं विपाट्शब्दं शरत्प्रभृतिषु पठति ॥

(प्रदीपः) यदयमिति । नित्यार्थः पाठः स्यादिति चेत्, व्यवस्थितविभाषया विपाट्शब्दस्य नित्यष्टज् भविष्यतीत्यदोषः ॥

(उद्योतः) नित्यार्थ इति । नदीपौर्णमासीत्यत्रान्यतरस्यांग्रहणानुवृत्तेरिति भावः ॥ व्यवस्थितेति । अत्र च ज्ञापकपरमिदमेव भाष्यं मानम् । केचिदेतस्माद्भाष्यात्तदीति सूत्रेऽन्यतरस्यांग्रहणं निवर्तयन्ति ॥

(आक्षेपभाष्यम्)

इह तर्हि प्राप्नोति—"नदीभिश्च" इति ॥

(समाधानभाष्यम्)

बहुवचननिर्देशान्न भविष्यति ॥

(प्रदीपः) बहुवचनेति । अन्यथा 'आप्नयाः' इत्यादं यथैकवचननिर्देशस्तथेहापि कर्तव्यः स्यात् ॥

(आक्षेपभाष्यम्)

स्वरूपविधिस्तर्हि प्राप्नोति ॥

(समाधानभाष्यम्)

बहुवचननिर्देशादेव न भविष्यति ॥

(उद्योतः) बहुवचननिर्देशादेवेति । तस्मादपीत्यर्थः अशब्दसंज्ञेति निषेधादित्यपि बोध्यम् । तत्प्रत्याख्याने त्वयमेव हेतुः । अतोऽस्मान्निषेधान्नदीपौर्णमासीत्यादौ स्वरूपग्रहणमपि दुर्लभमित्यपास्तम्, लक्ष्यानुसारेण तत्प्रत्याख्यानेन सामर्थ्येन तस्याप्रवृत्तेः । नदीभिश्चेत्यादौ तु लक्ष्यानुसारादेवार्थग्रहणेन तद्वाचकानां ग्रहणमिति दिक् ॥

(उपसंहारभाष्यम्)

एवं न चेदमकृतं भवति—"कृत्रिमाकृत्रिमयोः कृत्रिमे संप्रत्ययः" इति । न च कश्चिद्दोषो भवति ॥

(प्रदीपः) न चेदमिति । अनाश्रितमित्यर्थः ॥

(उद्योतः) अस्य न्यायत्वादकृतमित्ययुक्तमत आह—अनाश्रितमिति ॥

(१७९ आक्षेपसाधकवार्तिकम् ॥ २ ॥)

॥ * ॥ उत्तरार्थं च ॥ * ॥

(भाष्यम्)

उत्तरार्थं च संख्याग्रहणं कर्तव्यम् । "ष्णान्ता षट्" षकारनकारान्तायाः संख्यायाः षट्संज्ञा यथा स्यात् । इह मा भूत्—पामानः-विप्रुष इति ॥

(प्रदीपः) उत्तरार्थं चेति । अयं हि सूत्रोपात्तः संख्याशब्दः स्वरूपपदार्थकः । उत्तरत्र संज्ञिनिर्देशेन प्रयोजनम् ॥

(उद्योतः) स्वरूपेति । नै चैवं षडादिसामानाधिकरण्यानुपपत्तिः । शब्दार्थयोरभेदारोपेण तदुपपत्तेरिति भावः ॥ संज्ञिनिर्देशेनेति । संख्याशब्दबोध्यपञ्चादिशब्दपरेण संख्याशब्दनिर्देशेनेत्यर्थः ॥

(वार्तिकोक्ताक्षेपनिराकरणभाष्यम्)

इहार्थेन तावन्नार्थः संख्याग्रहणेन ॥

(प्रदीपः) इहार्थेनेति । इहार्थो यस्य-इति सामान्यविशेषभावान्न पौनरुक्त्यम् ॥

(उद्योतः) सामान्येति । अर्थशब्दोक्तसामान्यं प्रति 'इहार्थो यस्य' इत्यस्य विशेषत्वादित्यर्थः ॥

(आक्षेपस्मारणभाष्यम्)

ननु चोक्तम्-*इतरथा ह्यसंप्रत्ययोऽकृत्रिमत्वाद्यथा लोके*इति ?

(आक्षेपपरिहारभाष्यम्)

नैष दोषः । अर्थात्प्रकरणाद्वा लोके कृत्रिमाकृत्रिमयोः कृत्रिमे संप्रत्ययो भवति । अर्थो वाऽस्यैवंसंज्ञकेन भवति । प्रकृतं वा तत्र भवति—इदमेवंसंज्ञकेन कर्तव्यमिति ॥

आतश्चार्थात् प्रकरणाद्वा । अङ्ग हि भवान् ग्राम्यं पांशुरपादमप्रकरणज्ञमागतं ब्रवीतु—गोपालकमानय, कटजकमानयेति । उभयगतिस्तस्य भवति । साधीयो वा यष्टिहस्तं गमिष्यति ॥

(प्रदीपः) आतश्चेति । इतश्चेत्यर्थः ॥ अर्थः-सामर्थ्यम् । यथा-गोपालकमानय माणवकमध्यापयिष्यति-इति यष्टिहस्तस्याध्यापनासंभवात्संज्ञिनो ग्रहणम् ॥ प्रकरणं-प्रस्तावः । यथा-भोजनप्रकरणे सैन्धवमानय-इति लवणे प्रतीतिः, गमनप्रकरणे त्वश्वे ॥ ग्राम्यमिति । ऊहितुमसमर्थम् ॥ पांशुरपादमिति । अचिरोषितम् । अत एवाप्रकरणज्ञम् ॥ उभयगतिरिति । किं संज्ञेयं यस्य कस्यचिन्निर्दिष्टा स्यात्, उत यष्टिहस्तोऽस्य विवक्षितः स्यात्-इति संदेहवान् भवतीत्यर्थः ॥ साधीयो वेति । यो मम प्रसिद्धः सोऽनेन चोदितो न च ममैवंसंज्ञकः प्रसिद्ध इत्येवं मन्यते । लोके गोपालकशब्दः संज्ञिनि नियम्यमानः संज्ञ्यन्तरं निवर्तयति, क्रियानिमित्तं त्वर्थं न निरस्यति, तुल्यजातीयविषय एव हि नियमो भवति ॥

(उद्योतः) भाष्ये-अर्थादित्यादि । लोके कृत्रिमग्रहणे न कृत्रिमत्वं कारणं, किं त्वन्यदेवेति भावः ॥ अर्थः-सामर्थ्यम् । तदेव दर्शयति—अर्थो वाऽस्येति । अस्य वाक्यस्यार्थः=अध्यापनादिरूपं प्रयोजनं एवंसंज्ञकेन भवति तत्रास्यैव सामर्थ्यमित्यर्थः ॥ प्रकृतं वेति । इदमेवंसंज्ञकेन कर्तव्यमिति तत्र प्रयोजनं प्रकृतं बुद्धिस्थं भवति, संज्ञाया बुद्धिस्थत्वादित्यर्थः । इदमन्येषामपि पदार्थनियामकानामुपलक्षणम् ॥ यद्यपि रूढिर्योगापहारिणीत्यप्यत्र संभवति, तथापि प्रकरणादिसहकृतो योगोऽपि बलवानित्यभिप्रेत्येदमेवोक्तम् ॥

अन्वयमुक्त्वा व्यतिरेकेणाप्यर्थादेर्हेतुत्वं प्रतिपादयितुं भाष्ये-आत-

श्चेति॥ उभयगतिः-उभयविषयकं ज्ञानं तात्पर्यसन्देहरूपमित्याशयेनाह—किं संज्ञेयमिति। वक्तृतात्पर्यविषयसन्देहवानित्यर्थः॥ ननु रूढेर्योगार्थापहारकत्वेन कथं संदेह इति चेन्न। तत्तत्पुरुषं प्रति प्रसिद्धरूढ्यर्थस्यैव योगापहारकत्वं नान्यस्येति भावात्॥ तदेव ध्वनयन्नाह—साधीय इति। क्रियाविशेषणमव्ययं वा सम्यगर्थकम्॥ यष्टिहस्तं गमिष्यति-तद्विषयमेव तात्पर्यं ग्रहीष्यतीत्यर्थः॥ ननु संज्ञाकरणस्य नियमार्थत्वाद्योगार्थप्रतीतिः श्रोतुर्भ्रम इत्यत आह—एवं मन्यते। लोके इति। इदमपि स्वरीत्या॥

(आक्षेपसाधकभाष्यम्)

यथैव तर्ह्यर्थात्प्रकरणाद्वा लोके कृत्रिमाकृत्रिमयोः कृत्रिमे संप्रत्ययो भवति, एवमिहापि प्राप्नोति। जानाति ह्यसौ बह्वादीनामियं संज्ञा कृतेति॥

(प्रदीपः) **एवमिहापीति**। बह्वादय एवात्र संख्यात्वेन प्रकृता इति भावः॥

(उद्द्योतः) अत्र-शास्त्रे। प्रकृताः-बुद्धौ संनिहिताः॥ अनेनात्रापि प्रकरणमस्तीत्युक्तं भवति। बुद्धिसंनिधिरेव प्रकरणम्॥

(समाधानसाधकभाष्यम्)

न यथा लोके तथा व्याकरणे। उभयगतिः पुनरिह भवति॥

(प्रदीपः) **न यथा लोक इति**। संख्याशब्दो हि बह्वादिप्रतिपादनाय संज्ञात्वेन विनियुक्तः, न त्वेकादिसंख्यानिरासाय। अधिकार्थप्रतिपत्त्यर्थत्वादिह संज्ञाकरणस्य॥

(उद्द्योतः) **संज्ञात्वेन विनियुक्त इति**। ज्ञापिताज्ञातशक्तिक इत्यर्थः॥ अत एव न नियमार्थतेत्याह—**न त्विति**। तुल्यन्यायेन संज्ञासूत्रमात्रस्य नियमार्थत्वाभावः सूचितः॥ इह-संख्याप्रदेशे, **अधिकार्थे**त्यादिनाऽन्वेति॥ भाष्ये-**न यथे**त्यादि। व्याख्यातृपरंपरावगतवक्तृतात्पर्यानुपपत्त्या प्रकरणाद्यनादरेणोभयगतिरिति भाष्यार्थ इत्यन्ये॥

(उभयगत्युदाहरणभाष्यम्)

अन्यत्रापि, नावश्यमिहैव।

तद्यथा-"कर्तुरीप्सिततमं कर्म" इति कृत्रिमा कर्मसंज्ञा। कर्मप्रदेशेषु चोभयगतिर्भवति—"कर्मणि द्वितीया" इति कृत्रिमस्य ग्रहणम्, "कर्तरि कर्मव्यतिहारे" इत्यकृत्रिमस्य॥

(प्रदीपः) **कर्मणि द्वितीयेति**। ङ्याप्प्रातिपदिकादनभिहिते कर्मणि संख्यायां द्वितीया विधीयते। न च क्रियायाः संख्या संभवतीति सामर्थ्यात्कारकग्रहणम्। 'कर्तरि कर्मव्यतिहारे' इत्यत्र धातोः साक्षात् क्रियायां वृत्त्या क्रियाया एव ग्रहणम्॥

(उद्द्योतः) **कर्मणि संख्यायामिति**। कर्मगतसङ्ख्यायामित्यर्थः॥ **न चेति**। तस्या अद्रव्यत्वेन द्रव्यधर्मलिङ्गाद्ययोगादिति भावः॥ यद्यपि रूपयादिसूत्रस्थभाष्यादेकत्वं क्रियायामस्ति, तथापि द्वित्वाद्यभाव इति तात्पर्यम्॥ **कारकम्**-शक्तिमद्द्रव्यम्॥ **साक्षात्क्रियाया**मित्यस्य क्रियायामेव, न तु कर्मकारके इत्यर्थः। अन्यथा साक्षात्पदप्रयोजनं चिन्त्यं स्यात्। न हि धातोः परंपरयाऽपि कारके वृत्तिरस्ति येन तद्याधृत्या चारितार्थ्यं स्यादित्याहुः॥

(उभयगत्युदाहरणभाष्यम्)

तथा-"साधकतमं करणम्" इति कृत्रिमा करणसंज्ञा। करणप्रदेशेषु चोभयगतिर्भवति—"कर्तृकरणयोस्तृतीया" इति कृत्रिमस्य ग्रहणम्, "शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे" इत्यत्राकृत्रिमस्य॥

(प्रदीपः) **कण्वमेघेभ्यः करण इति**। तव्यादिप्रत्ययोत्पत्त्यर्थं धातुसंज्ञा क्रियते, क्रियावाचिनश्च तव्यादयः साधने उत्पद्यन्त इति सामर्थ्यात् क्रियाग्रहणम्॥

(उद्द्योतः) धातुसंज्ञा-क्यङन्तस्य 'सनाद्यन्ता' इत्यनेन॥ साधने-कारके तव्यादयः, अतः कारकापेक्षितक्रियावाचिन एवोत्पद्यन्त इत्यन्वयः॥

(उभयगत्युदाहरणभाष्यम्)

यथा-"आधारोऽधिकरणम्" इति कृत्रिमाऽधिकरणसंज्ञा। अधिकरणप्रदेशेषु चोभयगतिर्भवति-"सप्तम्यधिकरणे च" इति कृत्रिमस्य ग्रहणम्, "विप्रतिषिद्धं चानधिकरणवाचि" इत्यकृत्रिमस्य॥

(प्रदीपः) **विप्रतिषिद्धमिति**। द्वन्द्वावयवानां शक्त्यनभिधायित्वादधिकरणं द्रव्यं गृह्यते॥

(वार्तिकोक्ताक्षेपे द्वितीयसमाधानभाष्यम्)

अथवा-नेदं संज्ञाकरणम्। तद्वदतिदेशोऽयम्, बहुगणवतुडतयः संख्यावद्भवन्तीति॥

(प्रदीपः) **तद्वदतिदेशोऽयमिति**। संख्याकार्यातिदेशोऽयमित्यर्थः। यदि हि संज्ञा स्यात् टि-घु-भादिसंज्ञावदेकाक्षरा क्रियेत। तस्माल्लौकिकार्थाभिधायी संख्याशब्द उपादीयमानोऽतिदेशार्थत्वमस्य बोधयति॥

(उद्द्योतः) एवं सर्वसंज्ञाविषये समाधाय प्रकृतविषये समाधानान्तराण्याह—अथवेति-(भाष्ये)॥

(आक्षेपभाष्यम्)

स तर्हि वतिनिर्देशः कर्तव्यः॥

(समाधानभाष्यम्)

न कर्तव्यः॥

(आक्षेपसाधकभाष्यम्)

न ह्यन्तरेण वतिमतिदेशो गम्यते॥

(आक्षेपबाधकभाष्यम्)

अन्तरेणापि वतिमतिदेशो गम्यते। तद्यथा-'एष ब्रह्मदत्तः' अब्रह्मदत्तं ब्रह्मदत्त इत्याह ते मन्यामहे ब्रह्मदत्तवदयं भवतीति। एवमिहाप्यसंख्यां संख्येत्याह संख्यावदिति गम्यते॥

(उद्द्योतः) ब्रह्मदत्त इत्युक्तिविषयस्याब्रह्मदत्तत्वं स्फोरयितुं ब्रह्मदत्तव्यक्तिं निर्दिशति—**एष ब्रह्मदत्त इति**॥ **असंख्यां संख्येत्याहेति**। नियतविषयपरिच्छेदहेतुर्हि सङ्ख्या। एवंच बहुत्वादेरसङ्ख्यात्वमिति भावः॥ बहुत्वं हि त्र्यादिसङ्ख्याव्यापकमखण्डोपाधिरूपम्॥

(वार्तिकोक्ताक्षेपे तृतीयसमाधानभाष्यम्)

अथवा—आचार्यप्रवृत्तिर्ज्ञापयति—भवत्येकादिकायाः संख्यायाः संख्याप्रदेशेषु संप्रत्यय इति। यदयं "संख्याया अतिशदन्तायाः कन्" इति तिश-

दन्तायाः प्रतिषेधं शास्ति ।

कथं कृत्वा ज्ञापकम् ?

न हि कृत्रिमा त्यन्ता शदन्ता वा संख्याऽस्ति ॥

(प्रदीपः) **अथवेति** । गुरुसंज्ञाकरणादेकादयः संख्याशब्देन प्रदेशेषु न त्यज्यन्त इति लिङ्गेनाप्यनुमीयत इत्यर्थः ॥

(उद्योतः) गुर्विति । नन्वतिशन्दन्ताया इति लिङ्गात्कृन्विधौ कृत्रिमा न गृह्येतेति चेन्न । शास्त्रबाधापेक्षया उभयग्रहणज्ञापकत्वस्यैवौचित्यादिति भावः ॥

(समाधानबाधकभाष्यम्)

ननु चेयमस्ति डतिः ॥

(समाधानसाधकभाष्यम्)

यत्तर्हि शदन्तायाः प्रतिषेधं शास्ति ॥

(संपूर्णसूत्रज्ञापकत्वाभ्युपगमभाष्यम्)

यच्चापि त्यन्तायाः प्रतिषेधं शास्ति ॥

(आक्षेपस्मारणभाष्यम्)

ननु चोक्तम्-डत्यर्थमेतत् स्यात्-इति ॥

(समाधानभाष्यम्)

"अर्थवद्ग्रहणे नानर्थकस्य" इति अर्थवतस्तिशब्दस्य ग्रहणम् । न च डतेस्तिशब्दोऽर्थवान् ॥

(प्रदीपः) **अर्थवत इति** । ननूभयसंभवे-इयं परिभाषोपतिष्ठते । उत्यन्ता च कृत्रिमाऽस्ति, डतेश्च तिशब्दोऽनर्थक एवेति तस्यैव निषेधः स्यादित्यज्ञापकस्त्यन्तायाः प्रतिषेधः । नैष दोषः । 'अतिशदन्तायाः' इत्युच्चारणकाल एवार्थवतस्तिशब्दस्य ग्रहणमिति प्रतीतिरिति ज्ञापकत्वमेव प्रतिषेधस्य ॥

(उद्योतः) **नैष इति** । 'अतिशदन्तायाः' इत्यस्य बहुव्रीहिगर्भतत्पुरुषत्वेन सङ्ख्याविशेषणतया विशिष्टबुद्धौ विशेषणज्ञानस्य कारणत्वाच्च तत्पदजन्योपस्थितिकालेऽर्थवदनर्थकयोः संभवेन पूर्वमर्थवत एव ग्रहणे निर्णीते पश्चात्संख्यापदार्थान्वयवेलायां जायमानानुपपत्तिज्ञानेन ज्ञापकत्वमेव कल्प्यत इति भावः । यैतत्पक्षद्वये महासंज्ञाया अनुग्राहकत्वं वक्तुमयुक्तम्, तन्मूलकपक्षान्तरस्याग्रे वक्ष्यमाणत्वादित्यन्ये ॥

(चतुर्थं समाधानभाष्यम्)

अथवा महतीयं संज्ञा क्रियते । संज्ञा च नाम यतो न लघीयः ॥

कुत एतत् ?

लघ्वर्थं हि संज्ञाकरणम् । तत्र महत्याः संज्ञायाः करण एतत्प्रयोजनम्—अन्वर्थसंज्ञा यथा विज्ञायेत, संख्यायतेऽनया-संख्येति । एकादिकया चापि संख्यायते ॥

(प्रदीपः) **अथवेति** । ननु महत्याः संज्ञायाः करणात्तदर्थानुगतानामुपात्तानामेव संज्ञिनां भवतु संज्ञा । यथा सर्वादीनामेव संज्ञा, न त्वधिकानाम् । तेन बहुगणशब्दयोः सङ्घवैपुल्यवाचिनोः संज्ञा मा भूत्, एकादीनां तु कथं स्यात् ? नैष दोषः । इहान्वर्थसंज्ञाकरणेन तावदनुरूपः संज्ञी सर्व आक्षिप्यते । तेनैकादीनां तावत् ग्रहणं भवति, पश्चात् 'बहुगणवतुडति' इति भूर्यादिनिवृत्त्यर्थं नियमार्थं व्याख्यायते । अत एव सङ्घवैपुल्यवृत्त्योर्बहुगणशब्दयोः संज्ञा न भवति । तद्वदतिदेशपक्षेऽपि परस्परसाहचर्यात् संख्यावाचिनोरेव भूर्यादिनिवृत्तये नियमायातिदेशः क्रियत इत्यतिप्रसङ्गो न भवति ॥

(उद्योतः) भाष्ये—**संज्ञा च नामेति** । **नाम**-प्रसिद्धमेतत्, यतोऽन्यल्लघीयो न भवति सा संज्ञेति ॥ **तदर्थानुगतानामिति** । सङ्ख्यानकरणत्वसमानाधिकरणसङ्ख्याशब्दवदभिन्ना बह्वादय इत्यर्थादिति भावः ॥ **कथं स्यादिति** । महासंज्ञाकरणस्य चरितार्थतया कृत्रिमन्यायबाधे मानाभावादिति भावः ॥ **सर्व इति** । नियतानियतसङ्ख्यावाचीत्यर्थः ॥ **आक्षिप्यत इति** । 'सङ्ख्या' इति विभक्तसूत्रे इति शेषः । एवंच सङ्ख्यानकरणीभूताः सङ्ख्यासंज्ञका इत्यर्थः ॥ संज्ञायाः संख्यानकरणत्वाश्रयतया तद्वाचकं पदमुपस्थितान्वर्थवाचकमेव कल्प्यत इत्ययमेवात्राक्षेप इति भावः ॥ **नियमार्थमिति** । 'बहुगण' इति द्वितीयसूत्रे सङ्ख्येति वर्तते । अनियतसङ्ख्यावाचिनां चेद्बह्वादीनामेवेति भावः ॥ **अत एवेति** । अन्वर्थत्वाश्रयणादेवेत्यर्थः ॥ **संज्ञा न भवतीति** । प्राप्तेरेवाभावादिति भावः ॥ **सङ्ख्यावाचिनोरेवेति** । बहुगणयोरित्यर्थः ॥ **नियमायेति** । नियमफलक इत्यर्थः ॥ **परे** तु—परस्परसाहचर्यात्सङ्ख्याव्यापकार्थवाचिनोरेव बहुगणयोर्ग्रहणं, न तु सङ्घवैपुल्यवचनयोरिति व्यर्थाऽन्वर्थसंज्ञा । तस्मात्प्रदेशेषु लोकप्रसिद्धकेवलयोगार्थस्यापि ग्रहणार्थं महती संज्ञेति भाष्याशयः ॥ **असङ्ख्यां सङ्ख्येत्याहेतिभाष्येण** बह्वादिषु सङ्ख्यापदयोगार्थाभावबोधनाच्चेति योगविभागो व्यर्थः ॥ '**एकादिकया चापि सङ्ख्यायते**' इत्यस्य एकादिकया च संख्यायते साऽपि सङ्ख्याप्रदेशेषु यथा गृह्येतेति महासंज्ञाकरणमित्यर्थः । चस्तु वाक्यालङ्कारे । उभावपि वा वाक्यालङ्कार एव । यद्वा बह्वादिकयाऽपि सङ्ख्यायते स्वव्याप्यन्त्रित्वादिद्वारेत्यर्थः ॥ वत्वन्तडत्यन्तयोर्यावदादिशब्दकतिशब्दयोर्यद्यपि साक्षात्सङ्ख्यानकरणीभूतार्थप्रतिपादकत्वमुपपादयितुमशक्यम्, तथापि कतीत्यत्र सङ्ख्यानकरणीभूतार्थविषयप्रश्नार्थकत्वेन तत्त्वम् । एवं वत्वन्तेऽप्यूह्यमित्याहुः ॥

('उत्तरार्थं च' इति वार्तिकोक्तप्रयोजनप्रत्याख्यानभाष्यम्)

उत्तरार्थेन चापि नार्थः संख्याग्रहणेन । इदं प्रकृतमुत्तरत्रानुवर्तिष्यते ॥

(आक्षेपभाष्यम्)

इदं वै संज्ञार्थम्, उत्तरत्र च संज्ञिविशेषणेनार्थः । न चान्यार्थं प्रकृतमन्यार्थं भवति ॥ न खल्वप्यन्यत्प्रकृतमनुवर्तनादन्यद्भवति । न हि गोधा सर्पन्ती सर्पणादहिर्भवति ॥

(प्रदीपः) **संज्ञिविशेषणेनार्थ इति** । 'ष्णान्ता' इत्यनेन विशिष्टं संज्ञिनं प्रतिपादयितुमुपयोग इत्यर्थः ॥ **न चान्यार्थमिति** । एकशब्दत्वदर्शन इति भावः ॥ भवतु तर्हि प्रतियोगं शब्दभेद इत्याह—**न खल्वपीति** । यथा गोधा देशान्तरगमनमात्रेण गोधात्वं न जहाति, एवं शब्दोऽपि रूपा-

न्तरं न गृह्णातीत्यर्थः ॥

(उद्द्योतः) भाष्ये—संज्ञार्थमिति । संज्ञा शब्दस्वरूपं, तदर्थकमित्यर्थः । संज्ञिनिरूपितसङ्ख्याशब्दनिष्ठशक्त्यवगमार्थं स्वरूपपरमिति भावः ॥ ननु ष्णान्तत्वेनेन सङ्ख्या विशेष्यत इति संज्ञिविशेषणं सङ्ख्याग्रहणमित्ययुक्तमत आह—ष्णान्तेति । भाष्ये संज्ञी=पदसंज्ञासंज्ञी विशेष्यते=स्वेतरव्यावृत्ततया प्रतिपाद्यते येनेत्यर्थः ॥ ननु स्वरितत्वबलेनानुमीयमानस्य शब्दान्तरत्वाच्छब्दभेदेनार्थभेदस्य सत्त्वेन न चान्यार्थमित्ययुक्तमत आह—एकेति । यस्य स्वरितत्वं प्रतिज्ञातं तदेवानुवर्तते, न तु तज्जातीयं शब्दान्तरमिति भावः ॥ अर्थाधिकार एव चाभ्यर्हितः, तदर्थस्य चायोग्यत्वादिहासंबन्ध इति भावः ॥ इत्याहेति । इत्याशङ्क्याहेत्यर्थः ॥ भाष्ये—न खल्वपीति । प्रकृतमनुवर्तनात्—देशान्तरगमनादन्यद्भवतीति न खलु-इत्यन्वयः ॥ यथेति । सर्पणस्योभयत्र तुल्यत्वेन प्रसक्तमहित्वं गोधाया वार्यत इति नार्थः, सर्पणस्याहिशब्दप्रवृत्तिनिमित्तत्वाभावात्; किं तु देशान्तरगमनं नान्यत्वापादकमित्यर्थ इति भावः ॥ रूपान्तरम्—अर्थभेदम् ॥

(आक्षेपप्रथमयुक्तिसमाधानभाष्यम्)

यत्तावदुच्यते—'न चान्यार्थं प्रकृतमन्यार्थं भवति' इति ।

अन्यार्थमपि प्रकृतमन्यार्थं भवति । तद्यथा—शाल्यर्थं कुल्याः प्रणीयन्ते, ताभ्यश्च पानीयं पीयते, उपस्पृश्यते च, शालयश्च भाव्यन्ते ॥

(प्रदीपः) अन्यार्थमपीति । पदार्थानां शक्तिवैचित्र्यात् ॥

(उद्द्योतः) पदार्थानामिति । द्वन्द्वः ॥ शक्तिवैचित्र्यात्—अनेकशक्तित्वादित्यर्थः ॥ एवंच पूर्वत्र तया शक्त्या स्वरूपपरस्यापि उत्तरत्रान्यया शक्त्या योग्यतावशादर्थपरत्वे बाधकाभावः । शब्दाधिकारोऽत्र लक्ष्यानुरोधादाश्रीयत इति भावः ॥

(आक्षेपद्वितीययुक्तिसमाधानभाष्यम्)

यदप्युच्यते—'न खल्वप्यन्यत् प्रकृतमनुवर्तनादन्यद्भवति । नहि गोधा सर्पन्ती सर्पणादहिर्भवति' इति ।

भवेत् द्रव्येष्वेतदेवं स्यात् । शब्दस्तु खलु येन येन विशेषेणाभिसंबध्यते तस्य तस्य विशेषको भवति ॥

(प्रदीपः) शब्दस्त्विति । स्वरितत्वेन वाक्यान्तरे शब्दान्तरं वाक्यार्थानुग्राहिवस्तुप्रतिपादनयोग्यमनुमीयते । सादृश्यात्तु तत्त्वाध्यवसाय इत्यर्थः ॥

(उद्द्योतः) [भाष्ये] भवेत् द्रव्येष्वेतदेवं स्यादिति । स्यादिति संभावनायां लिङ् । भवेदिति प्रार्थनायाम् । द्रव्यविषये पूर्वोक्तार्थकर्तृका संभाविता सत्ता भवत्वित्यर्थः ॥ शब्दभेदनयेऽपि न क्षतिरित्याह—शब्दस्त्विति ॥ येन येन विशेषेति । विशेष्यत इति विशेषः=परिच्छेद्यम्, विशेषकः=परिच्छेदकः, तत्परिच्छेदकार्थवानन्य एव शब्दो भवतीत्यर्थः ॥ तदुपपादयति—स्वरितत्वेनेति ॥

(समाधानयुक्त्यन्तरभाष्यम्)

अथवा-सापेक्षोऽयं निर्देशः क्रियते । न चान्यत्किंचिदपेक्ष्यमस्ति । ते संख्यामेवापेक्षिष्यामहे ॥

(प्रदीपः) सापेक्षोऽयमिति । स्त्रीलिङ्गेन निर्देशः कृतः । तत्र प्रकृतत्वादन्यपदार्थत्वेन संख्या स्वरितत्वेन विनाऽप्यपेक्ष्यत इत्यर्थः ॥

(१८० आक्षेपवार्तिकम् ॥ ३ ॥)

॥ * ॥ अध्यर्धग्रहणं च समासकन्विध्यर्थम् ॥ * ॥

(भाष्यम्)

अध्यर्धग्रहणं च कर्तव्यम् ।

किं प्रयोजनम् ?,

'समासकन्विध्यर्थम्' । समासविध्यर्थम्, कन्विध्यर्थं च ॥ समासविध्यर्थं तावत्-अध्यर्धशूर्पम् । कन्विध्यर्थम्—अध्यर्धकम् ॥

(प्रदीपः) अध्यर्धग्रहणं चेति । वार्तिके संख्याग्रहणं कर्तव्यत्वेन स्थितम् । तदपेक्षया समुच्चयार्थश्चशब्दः । विध्यर्थं चेदं, अध्यर्धशब्दस्य त्रिभागचतुर्भागादिशब्दवदसंख्यावाचित्वात् । अर्धशब्दश्चैकदेशवाची न संख्यावाची, एकदेशादिशब्दवत् । तस्याधिशब्देन समासे कृते यौगिकोऽर्थः प्रतीयते, न संख्या ॥ अध्यर्धशूर्पमिति । अध्यर्धेन शूर्पेण क्रीतमिति 'दिक्संख्ये' इत्यनुवर्तमाने 'तद्धितार्थ' इति समासः । ततः 'शूर्पादञन्यतरस्याम्' इति अञ्छणो वा 'अध्यर्धपूर्व' इति लुक् ॥ अध्यर्धकमिति । 'संख्याया अतिशदन्तायाः कन्' इति कन् ॥

(उद्द्योतः) अध्यर्धस्यासंख्यावाचित्वमुक्तमुपपादयति—अर्धशब्दश्चेति ॥

(१८१ आक्षेपप्रयोजनवार्तिकम् ॥ ४ ॥)

॥ * ॥ लुकि चाग्रहणम् ॥ * ॥

(भाष्यम्)

लुकि चाध्यर्धग्रहणं न कर्तव्यं भवति—"अध्यर्धपूर्वात् द्विगोर्लुगसंज्ञायाम्" इति । "द्विगोः" इत्येव सिद्धम् ॥

(प्रदीपः) द्विगोरित्येव सिद्धमिति । 'समासकन्विध्यर्थम्' इति च संबन्धसामान्ये षष्ठी । तेन समासे विधीयमाने समासनिमित्ते चान्यस्मिन् कार्ये विधीयमान इत्यर्थः । तेन द्विगुनिमित्तो लुगपि लभ्यते ॥

अन्ये त्वाहुः—अध्यर्धशब्दः संख्यावाच्येव । तथाहि गण्यते—एकोऽध्यर्धः, द्वौ-अध्यर्धौ, अध्यर्धतृतीया इति । तन्मते नियमार्थ-अध्यर्धशब्दस्यैव संख्यात्वेन ग्रहणं यथा स्यात्, सार्धादीनां मा भूदिति । वाक्यभेदेन च द्वितीयो नियमः । तस्य च समासकन्विध्यर्थं संख्यात्वं, न कार्यान्तरार्थमिति ॥

(उद्द्योतः) ननु समासकन्सिद्धये विधीयमाना संज्ञा कथं लुको निमित्तमत आह—समासेति । समासपदेन द्विगुसमास एव, तस्यैव सङ्ख्यानिमित्तकत्वात् । तन्निमित्तकमपि द्विगुनिमित्तकमेवेत्याह—तेन द्विग्विति ॥

(१८२ आक्षेपवार्तिकम् ॥ ५ ॥)

॥*॥ अर्धपूर्वपदश्च पूरणप्रत्ययान्तः ॥*॥

(भाष्यम्)

अर्धपूर्वपदश्च पूरणप्रत्ययान्तः संख्यासंज्ञो भवतीति वक्तव्यम् ।

किं प्रयोजनम् ?

समासकन्विध्यर्थमेव । समासविध्यर्थं कन्विध्यर्थं च । समासविध्यर्थं तावत्—अर्धपञ्चमशूर्पम् । कन्विध्यर्थम्—अर्धपञ्चमकम् ॥

(१८३ आक्षेपवार्तिकम् ॥ ३ ॥)

॥ * ॥ अधिकग्रहणं चालुकि समासोत्तरपदवृद्ध्यर्थम् ॥ * ॥

(भाष्यम्)

अधिकग्रहणं चालुकि कर्तव्यम् ।

किं प्रयोजनम् ?

'समासोत्तरपदवृद्ध्यर्थम्' । समासविध्यर्थमुत्तरपदवृद्ध्यर्थं च । समासविध्यर्थं तावत्—अधिकषाष्टिकः, अधिकसाप्ततिकः ॥ उत्तरपदवृद्ध्यर्थम्—अधिकषाष्टिकः, अधिकसाप्ततिकः ॥

अलुकीति किमर्थम् ?

अधिकषाष्टिकः, अधिकसाप्ततिकः ॥

(प्रदीपः) अधिकषाष्टिक इति । अधिकया षष्ट्या क्रीत इति संख्याविशेषणमधिकशब्दः, न संख्येति वचनम् । 'तद्धितार्थ' इति समासः । 'प्राग्वतेष्ठञ्' । 'अलुकि' इति वचनाल्लुकि कर्तव्ये संख्यासंज्ञा नास्तीति 'अध्यर्धपूर्व' इति लुङ्न भवति । ततः 'संख्यायाः संवत्सरसंख्यस्य च' इत्युत्तरपदवृद्धिः ॥ ननु 'उत्तरपदवृद्ध्यर्थं' इति वचनाल्लुङ् न भविष्यति, किं 'अलुकि' इत्यनेन । नैतदस्ति, अर्हत्यर्थात् परेष्वर्थेषु यः प्रत्ययस्तस्य लुगभावात्तत्रैवोत्तरपदवृद्धिः स्यात् ॥

(उद्द्योतः) भाष्ये—अधिकग्रहणं चेति । लुग्भिन्नसङ्ख्याकार्यसिद्ध्यर्थमधिकग्रहणं सङ्ख्यासंज्ञायां कर्तव्यमित्यर्थः ॥ नन्विति । ञ्णिदादिषु तद्विधानादिति भावः ॥ परेष्वर्थेष्विति । तमधीष्ट इत्यादिष्वित्यर्थः ॥

(१८४ आक्षेपप्रयोजनवार्तिकम् ॥ ७ ॥)

॥ * ॥ बहुव्रीहौ चाग्रहणम् ॥ * ॥

(भाष्यम्)

बहुव्रीहौ चाधिकशब्दस्य ग्रहणं न कर्तव्यं भवति । "संख्ययाऽव्ययासन्नादूराधिकसंख्याः संख्येये" इति । संख्येत्येव सिद्धम् ॥

(१८५ प्रत्याख्यानवार्तिकम् ॥ ८ ॥)

॥ * ॥ बह्वादीनामग्रहणम् ॥ * ॥

(भाष्यम्)

बह्वादीनां ग्रहणं शक्यमकर्तुम् ॥

(आक्षेपभाष्यम्)

केनेदानीं संख्याप्रदेशेषु संख्यासंप्रत्ययो भविष्यति ?

(प्रत्याख्यानसाधकभाष्यवार्तिकम्)

ज्ञापकात् सिद्धम् ॥

ज्ञापकं किम् ?

यदयं-"वतोरिड्वा" इति संख्याया विहितस्य कनो वत्वन्तादिटं शास्ति ॥

(आक्षेपभाष्यम्)

वतोरेव तज्ज्ञापकं स्यात् ॥

(समाधानभाष्यम्)

नेत्याह । योगापेक्षं ज्ञापकम् ॥ २३ ॥

(प्रदीपः) ज्ञापकात्सिद्धमिति । एकादिश्नियतसंख्यावाचित्वं बह्वादीनां नास्तीति ज्ञापकाश्रयः ॥ योगापेक्षमिति । अस्य योगस्य प्रत्याख्यानादेतद्योगापेक्षमिति न बोद्धव्यम्, किंतु योगान् अपेक्षत इति–योगापेक्षम् । यदयं 'बहुपूगगणसङ्घस्य तिथुक्' 'वतोरिथुक्' 'षट्कति' इति डटि परत आगमं शास्ति, तज्ज्ञापयति—भवति संख्याकार्यमिति ॥ २३ ॥

(उद्द्योतः) नियतसङ्ख्यावाचित्वमिति । नियतविषयपरिच्छेदहेतुत्वरूपसङ्ख्यावाचित्वमित्यर्थः ॥ भाष्ये— यदयमिति । न च वैपुल्यादिवाचिनामपि संख्याकार्यापत्तिः, संख्यापदार्थसंबन्धिबह्वादिग्रहणज्ञापनेन चरितार्थस्य सर्वथा तदसंबन्धिवैपुल्यादिवाचकग्रहणज्ञापने सामर्थ्याभावात् । पूगादिभ्यो डडर्थं बहुगणेति सूत्रे कृतेऽपि ज्ञापकावश्यकत्वमिति भावः ॥ केचित्तु 'वतोरिड्वा' इत्यनेन संख्यानकरणत्वाभाववतामप्यन्येषां प्रयोगेषु दृश्यमानसंख्याकार्याणां संख्याकार्यं ज्ञाप्यते । तेनाधिकादीनामपि सिद्धं, तदाह—योगापेक्षमिति । प्रयोगापेक्षमित्यर्थः । एतेन पूगादिभ्यः शसादिप्रसङ्गोऽपि वारित इत्याहुः ॥ २३ ॥

(२३ षट्संज्ञासूत्रम् ॥ १ । १ । ५ आ. १२)

ष्णान्ता षट् ॥ १ । १ । २४ ॥

(अनिष्टापत्तीष्टानुपपत्तिनिराकरणाधिकरणम्)

(१८६ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ षट्संज्ञायामुपदेशवचनम् ॥ * ॥

(भाष्यम्)

षट्संज्ञायामुपदेशग्रहणं कर्तव्यम् । उपदेशे

षकारनकारान्ता संख्या षट्संज्ञा भवतीति वक्तव्यम् ।

किं प्रयोजनम् ?

शताद्यष्टनोर्नुम्नुडर्थम् । शतानि, सहस्राणि । नुमि कृते "ष्णान्ता षट्" इति षट्संज्ञा प्राप्नोति, उपदेशग्रहणान्न भवति ॥

अष्टानामित्यत्राऽऽत्वे कृते षट्संज्ञा न प्राप्नोति, उपदेशग्रहणाद्भवति ॥

(प्रदीपः) ष्णान्ता० ॥ २४ ॥ षट्संज्ञायामिति । प्रकृतिप्रत्ययविभागेन प्रतिपादनं गुणैः प्रापणमुपदेशः । तेन प्रकृतिप्रत्ययाद्युपदेशे षकारनकारान्ता या संख्या सा षट्संज्ञेत्यर्थः ॥ नुम्नुडर्थमिति । अर्थशब्दः प्रयोजनवाची । तत्र नुमि 'शतानि' इत्यादौ षट्संज्ञानिवृत्तिः प्रयोजनम्, नुटि तु विधीयमाने षट्संज्ञाप्रवृत्तिः प्रयोजनम् ॥

अष्टानामिति । परत्वान्नित्यत्वाच्चात्वे कृते नुटोऽप्राप्तिः । कार्यकालत्वात्संज्ञायाः प्रवृत्तेर्नास्त्यन्तरङ्गत्वम् ॥

(उद्द्योतः) ष्णान्ता षट् ॥ २४ ॥ स्वरूपप्रतिपत्त्यर्थाच्चोच्चारणस्यान्यत्रोपदेशत्वप्रसिद्धेरुपदेशग्रहणे षष्ठादिषु न स्यादत आह—प्रकृतीति । प्रकृतिप्रत्ययविभागेन प्रतिपादनरूपं यत् गुणैः प्रापणं तदुपदेशपदेनात्र गृह्यत इत्यर्थः ॥ एतदभिप्रायेणैवोपदेशेऽजिति सूत्रे वक्ष्यति—'संकीर्णावुद्देशोपदेशौ' इति ॥ प्रत्ययाद्युपदेश इति । आदिनाऽऽगमः । यथा सप्तम्यादौ सप्यशूभ्यां तुट्चेति प्रकृत्यादिभिरुपदेशे प्रातिपदिकस्वरूपबोधने या ष्णान्ता सङ्ख्या निष्पन्ना भवति सेत्यर्थः ॥ यद्यपि शतानीत्यादावपि नुमागमोपदेशेन नान्तसङ्ख्यानिष्पत्तिरस्ति तथापि विभक्त्युत्पत्त्यवधिभूतप्रातिपदिकस्वरूपनिष्पादकानामेव तेषां ग्रहणम् । न तु विभक्तिनिमित्तकानामपि, बहिरङ्गत्वादिति भावः ॥ तत्रेति । नुम्नुटोरर्थः=प्रयोजनं यस्येति बहुव्रीहिरिति भावः ॥ नन्वन्तरङ्गत्वात्पूर्वमेव षट्त्वं प्रवृत्तमात्वेऽपि बहिरङ्गतया आत्वस्यासिद्धत्वान्न निवर्त्स्यतीत्यत आह—कार्यकालेति ॥

(प्रत्याख्यानभाष्यम्)

उक्तं वा ।

किमुक्तम् ?

इह तावत्-शतानि सहस्राणीति 'सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य' इति ॥

अष्टनोऽप्युक्तम् ।

किमुक्तम् ?

अष्टनो दीर्घग्रहणं षट्संज्ञाज्ञापकमाकारान्तस्य नुडर्थम् इति ॥

(प्रदीपः) अष्टनो दीर्घेति । तत्र हि दीर्घग्रहणं 'अष्टसु' इति झलि उदात्तत्वनिवृत्त्यर्थं क्रियते । यदि च कृतात्वस्य षट्संज्ञा न स्यात् तदा 'अष्टसु' इति परत्वात् षट्स्वरः 'झल्युपोत्तमम्' इति भविष्यतीति किं दीर्घग्रहणेन ? कृतं च तत् कृतात्वस्याऽपि षट्संज्ञां ज्ञापयति । ततश्चापवादत्वात् षट्स्वरोऽनेन बाध्यत इति दीर्घपक्ष इवादीर्घपक्षेऽपि विभक्तेः स्वरः स्यादिति कर्तव्यं दीर्घग्रहणम् ॥

(उद्द्योतः) सुप उदात्तस्येति । अष्टन इति प्राप्तेरर्थः ॥ आद्युदात्तत्व-इति क्वाचित्कोऽपपाठः । यद्वा—दीर्घग्रहणं षट्त्वे यथोद्देशपक्षाश्रयणस्यैव ज्ञापकम् । तद्द्वारैव च षट्संज्ञाज्ञापकत्वम् । तत्पक्षे आत्वस्य बहिरङ्गतयाऽसिद्धत्वेन नान्तत्वबुद्ध्या षट्त्वमस्त्येव । स्पष्टं चेदमष्टनो दीर्घादित्यत्र कैयटे । किं च यथोद्देशपक्षे षट्त्वं स्थानिवद्भावेनापि सुलभम्, नकारान्तसङ्ख्यावाचकत्वसमानाधिकरणधर्मविशेषरूपस्य षट्त्वस्य समुदायधर्मत्वेन तन्निमित्तकनुडादेरल्विधित्वाभावादिति बोध्यम् । न चात्वस्य नित्यत्वात् 'अष्टसु' इति प्रयोग एवासङ्गत इति वाच्यम् । तद्वैकल्पिकत्वस्यापि ज्ञापनात् । यावता विनाऽनुपपन्नं तत्सर्वं ज्ञाप्यत इति सिद्धान्तात् ॥ परत्वादिति । अष्टन्स्वर आत्वपक्षे चरितार्थः । न च तत्प्रवृत्त्युत्तरमष्टस्वित्यादौ अष्टन्स्वरः स्यादेवेति वाच्यम् । सकृद्गतिन्यायाश्रयणात् ॥ अपवादत्वादिति । न च स्वरप्रवृत्तेः पूर्वमन्तरङ्गत्वात्वेकादेशस्याप्रवृत्तेर्येद्विस्रुपरमित्यादिप्रसमाप्यसंमतत्वेनाष्टाविस्यादावष्टन्स्वरश्चरितार्थ इति वाच्यम् । अष्टनो धृतादित्वादन्तोदात्तत्वेनैकादेश उदात्तेनेत्येव तत्रान्तोदात्तत्वसिद्धेः । धृतादावस्य पाठे चेदमेव भाष्यं मानम् । गौणे प्रियाष्टाभिरित्यादौ षट्स्वराष्टन्स्वरयोः प्रवृत्तिरस्त्येव । तेषामनभिधानाच्च । एतेन कदष्टन्शब्दोऽव्ययपूर्वपदप्रकृतिस्वरेणाद्युदात्त इति 'कदष्टौ' इत्यस्यैकादेशस्वरेणासिद्धेस्तत्राष्टस्वरः सावकाश इति परास्तम् । तस्याप्यनभिधानात् ॥

(एकदेशिसमाधानभाष्यम्)

अथवा-आकारोऽप्यत्र निर्दिश्यते—षकारान्ता नकारान्ता आकारान्ता च संख्या षट्संज्ञा भवतीति ॥

(समाधानबाधकभाष्यम्)

इहापि तर्हि प्राप्नोति—'सधमादो द्युम्न एकास्ताः' एका इति ॥

(प्रदीपः) एकास्ता इति । संख्यावाचित्वाभ्युपगमवादी व्यत्ययेन बहुवचनं मन्यते । अन्यवाचित्वाश्रयं तूत्तरम् ॥

(उद्द्योतः) ननु सङ्ख्यावाचित्वे 'एकाः' इति बहुवचनमनुपपन्नम्, अन्यत्र तु षट्संज्ञायाः प्राप्तिरेव नेत्यत आह—सङ्ख्येति ॥

(समाधानसाधकभाष्यम्)

नैष दोषः । एकशब्दोऽयं बह्वर्थः । अस्त्येव संख्यापदम् । तद्यथा-एको द्वौ बहव इति ॥

अस्त्यसहायवाची । तद्यथा—एकाग्नयः, एकहलानि, एकाकिभिः क्षुद्रकैर्जितमिति । असहायैरित्यर्थः ॥

अस्त्यन्यार्थे वर्तते । तद्यथा—'प्रजामेका रक्षत्यूर्जमेका इति', अन्येत्यर्थः । 'सधमादो द्युम्न एकास्ताः', अन्येत्यर्थः ।

तद्योऽन्यार्थे वर्तते तस्यैष प्रयोगः ॥

(समाधानबाधकभाष्यम्)

इह तर्हि प्राप्नोति–'द्वाभ्यामिष्टये विंशत्या च' इति ॥

(प्रदीपः) इह तर्हीति । 'द्वाभ्याम्' इति षट्स्वरः स्यात् ॥

(उद्द्योतः) षट्स्वर इति । "षट्त्रिचतुर्भ्यो हलादिः" इत्यनेन ॥ न च षान्तनान्तसाहचर्यादाकारान्तो बहुवचनान्त एव गृह्यत इति नायं दोषः । साहचर्यस्य सर्वत्राव्यवस्थापकत्वमित्याशयात् ॥

(सिद्धान्तिसमाधानान्तरभाष्यम्)

एवं तर्हि सप्तमे योगविभागः करिष्यते—"अष्टाभ्य औश्" । ततः–"षड्भ्यः" षड्भ्यश्च यदुक्तमष्टाभ्योऽपि तद्भवति । ततः–"लुक्" लुक् च भवति षड्भ्य इति ॥

(प्रदीपः) सप्तम इति । 'अष्टाभ्यः' इति कृतात्वानुकरणम् । औश्त्वविधानसामर्थ्याल्लुङ्न विधीयते ॥

(उद्द्योतः) कृतात्वेति । ततश्च कृतात्वस्य कार्यकालपक्षेऽसत्यपि षट्त्वेऽतिदेशाल्लुट्सिद्धिरित्यर्थः ॥ औश्त्वेति । अत एव विभक्ते जश्शसोरनुवृत्तिर्न । तथा हि सति लुगेवातिदिश्येतेति तद्वैयर्थ्यं स्पष्टमेव । विपरीतं तु न, व्याख्यानात् ॥

(समाधानान्तरभाष्यम्)

अथवा—उपरिष्टाद् योगविभागः करिष्यते—"अष्टन आ विभक्तौ" । ततः–"रायः" रायश्च विभक्तावाकारादेशो भवति । 'हलि' इत्युभयोः शेषः ॥

(प्रदीपः) हलीति । ततश्च 'अष्ट नाम्' इति नुटि कृते आत्वं भवति । जश्शसोस्तु 'अष्टाभ्यः' इति कृतात्वनिर्देशात् ज्ञापकादात्वं भवति । कृतात्वस्य हि निर्देशस्य प्रयोजनम्–यत्रात्वं तत्रौश्त्वं यथा स्यादिति । यदि ह्येतत्कृतात्वस्य निर्देशस्य प्रयोजनं न स्याल्लाघवार्थं 'अष्टभ्य औश्' इति ब्रूयात् ॥

(उद्द्योतः) ततश्चेति । न च संनिपातपरिभाषयाऽऽत्वं न स्यात्, अष्टानामिति रूपं तु नुटि 'नोपधायाः' इति दीर्घे नलोपे च सिद्धमिति वाच्यम् । असिद्धत्वेऽपि तद्विघातकविधेरनयाऽप्रवृत्तिबोधने नलोपस्याप्यनापत्तेः । अत एव 'पुक् ह्रस्वत्वस्यानिमित्तं स्याददीदपदित्यत्र' इति भाष्ये क्नुमेजन्तसूत्रे उक्तम् । 'जानातेर्मित्त्वेन ज्ञापकेन ह्रस्वविषये तदप्रवृत्तिः' इति च कैयटो वक्ष्यति । अन्यथा पुगपेक्षया ह्रस्वस्य बहिरङ्गासिद्धतया तस्या अप्राप्तौ भाष्यासङ्गतिः स्पष्टैव । किं चातिदेशिकनिमित्तविघाताभावमादाय नास्या अप्रवृत्तिः । एवं हि लक्ष्मीत्यादौ संबुद्धिह्रस्वे कृते संबुद्धिलोपे कृतेऽपि प्रत्ययलक्षणेन निमित्तविघाताभावात्तत्रास्या अतिव्याप्तिपरतत्सूत्रस्थभाष्यविरोधः । किं च गव्यितेत्यादौ संनिपातपरिभाषया लोपो नेति सिद्धान्तभङ्गः । यलोपस्य बहिर्भूतसृज्निमित्तकत्वेन बहिरङ्गतयाऽसिद्धत्वात् । वस्तुतस्तु षट्त्वसंनिपातनिमित्तको नुट् । न च तस्य संनिपातस्यात्वं विघातकम्, नापि नलोपः, स्थानिवद्भावेन तयोः कृतयोरपि षट्त्वसत्त्वात् । अत्र पक्षे दीर्घग्रहणं पुनःप्रसङ्गपक्षे अष्टभिरित्यत्र षट्स्वरे कृतेऽष्टन्स्वरव्यावृत्त्यर्थं सदात्वविकल्पज्ञापनार्थमिति बोध्यम् । अतिदेशविषयेऽपि तत्प्रवृत्तौ तु सिद्धं न इष्टम् ॥ अजाद्योर्जश्शसोस्तस्यात्वं न स्यादत आह—जश्शसोरिति ॥

(आक्षेपभाष्यम्)

यद्येवम्—प्रियाष्टौ-प्रियाष्टा-इति न सिध्यति, प्रियाष्टानौ-प्रियाष्टानः-इति प्राप्नोति ॥

(प्रदीपः) यद्येवमिति । हलादावुच्यमानमात्वमौजसोर्न प्राप्नोति । यत्राष्टार्थस्य प्राधान्यं तत्रौश्त्वेन भवितव्यम्, तत्रैव चौश्त्वेनात्वमनुमीयत इति जस्यप्यात्वमत्र ज्ञापकान्न प्राप्नोति । विभक्तिमात्रे त्वात्वं विधीयमानमौजसोः सिध्यति । 'अष्टन आ विभक्तौ' इत्यत्र 'पदाङ्गाधिकारे तस्य च तदुत्तरपदस्य च' इति तदन्तविधिसद्भावाद्बहुवचननिर्देशाभावात् गुणभूतेऽप्यष्टार्थे आत्वेन भाव्यमिति अत्रापि सिध्यतीति प्रश्नः ॥

(उद्द्योतः) भाष्ये—प्रियाष्टान इति प्राप्नोतीति । इत्येव प्राप्नोतीत्यर्थः । अन्यथाऽपकर्षाभावेऽपि आत्वस्य वैकल्पिकतया तस्य दुर्वारत्वेन भाष्यासङ्गतेः ॥ ननु जसि ज्ञापकसिद्धात्वप्राप्तेरौशश्च प्राप्तेराह—यत्रेति । बहुवचननिर्देशादिति भावः ॥ षड्भ्य इत्येतत्साहचर्यादस्य प्राधान्ये एव प्रवृत्तिरिति वा भावः ॥ तस्य च यथाप्रकारान्तरेण गौणेऽप्रवृत्तिस्तथा सर्वादिसूत्रे उपपादयिष्यते । शुद्धलक्ष्यैकचक्षुष्कस्यात्र पूर्वपक्षित्वमिति तात्पर्यम् ॥ औश्त्वेनेति । औशेत्यर्थः । त्वप्रत्ययप्रयोगस्तु अनुकरणात् अनुकार्यरूपे भावे प्रति बोध्यम् । 'औत्वे–' इत्यादिभाष्यप्रयोगात् ॥ औश्त्वेनेति । तद्विधायकसूत्रस्थात्वनिर्देशेनेत्यर्थः ॥ अत्र—गौणे ॥ ज्ञापकादिति । अस्य प्राप्तियोग्यमपीति शेषः । क्वचित्तु 'ज्ञापकात्' इति न दृश्यते ॥ नन्वपकर्षपक्षेऽपि अष्टनो विहितमात्वं कथं तदन्ते स्यादत आह—पदाङ्गेति ॥ बहुवचननिर्देशाभावादिति । साहचर्याभावादित्यपि बोध्यम् ॥

(समाधानसिद्धान्तिभाष्यम्)

यथालक्षणमप्रयुक्ते ॥ २४ ॥

(प्रदीपः) यथालक्षणमिति । यस्य विशिष्टः प्रयोगो न स्मर्यते नापि प्रयोगनिषेधस्मृतिः, तद्यथालक्षणमनुगन्तव्यम् । तदत्र मा भूदात्वमित्यर्थः ॥ नैव वा लक्षणमप्रयुक्ते प्रवर्तते, प्रयुक्तानामेव लक्षणेनान्वाख्यानात् ॥ २४ ॥

(उद्द्योतः) लक्षणैकचक्षुष्कस्यैवोत्तरमिति मत्वा व्याचष्टे—तदत्र मा भूदात्वमिति । पक्षान्तरेऽपि अनभिधानादात्वाभाव एव बोध्यः ॥ यत्तु भवत्येवात्रात्वमित्यर्थ इति । तन्न । अपकर्षपक्षे आत्वसाधकोपायाभावेन फलभेदापत्तेः ॥ नन्वयं भाष्यार्थो न युक्तः । तथा हि सतीष्यत एवैतदित्येव ब्रूयात् । किं चाप्रयुक्ते इति वाक्यशेषोऽसङ्गतः, प्रयुक्तेऽपि लक्षणानतिक्रमसत्त्वात् । प्रयुक्तानां हीदमन्वाख्यानमिति भाष्योक्तेश्चेत्यरुचेराह—नैव वेति । लक्षणस्याभावोऽलक्षणं, तस्य योग्यता–यथालक्षणमित्यव्ययीभावः । अप्रयुक्ते लक्षणाभावस्य योग्यता न तु लक्षणस्येत्यर्थः । एवं च तादृशप्रयोगोऽसाधुरिति भावः ॥ किं च भाष्यकारस्य लक्ष्यैकचक्षुष्कतया इयमेव व्याख्या ज्यायसी । एवं च हरदत्तादीनां प्रियाष्टन्शब्दादिषु आत्वादिप्रवृत्तिविचारोऽन्यश्च तत्प्रयोगविचारः प्रामादिक एवेत्यवधेयम् ॥ एतेन पूर्वव्याख्यानेऽस्य साधुत्वमुत्तरव्याख्यानेऽसाधुत्वमिति विरुद्धार्थकव्याख्यानद्वयमयुक्तम् ॥ किं च अष्टाभ्य इति निर्देशात्कृताकारादेवाष्टनो जश्शसोरौशिति तद्विषयेऽप्यात्वम् । अन्यथाऽष्टन इत्येव ब्रूयादिति

सात्मिकभाष्ये 'एकवचननिर्देशात् प्रधान एवोच्यते' इति प्रश्नाशयोऽपि चिन्त्य इत्यपास्तम् ॥ गौणे प्रियाष्टादीनामनभिधानमिति अस्मत्सिद्धान्तानुसारेण तद्भाष्यस्य सत्त्वात्। अस्यैव व्याख्यानान्तरप्रवृत्तेश्च ॥ २४ ॥

(२४ षट्संज्ञासूत्रम् ॥ १। १। ५ आ. १३ ॥)

डति च ॥ १। १। २५ ॥

(प्रत्याख्यानभाष्यम्)

इदं डतिग्रहणं द्विः क्रियते—संख्यासंज्ञायां, षट्संज्ञायां च। एकं शक्यमकर्तुम्।

कथम्?

यदि तावत् संख्यासंज्ञायां क्रियते, षट्संज्ञायां न करिष्यते।

कथम्?

"ष्णान्ता षट्" इत्यत्र 'डति' इत्यनुवर्तिष्यते ॥

(प्रदीपः) डति च ॥ २५ ॥ यदि तावदिति। तत्र वतुसाहचर्यात्तद्धित एव डतिर्गृह्यते, न तु पातेर्डतिः ॥

(उद्द्योतः) डति च ॥ २५ ॥ भाष्ये—यदि तावदिति। ष्णान्ता च षडिति सूत्रं पाठ्यं, तत्र चकारात्स्वरितत्वाद्वा संज्ञादनुवर्तमानं डतिग्रहणं संबध्यत इति भावः ॥ न तु पातेरिति। एवं चार्थाधिकारादिहापि तद्धितस्यैव ग्रहणमिति भावः ॥ सङ्ख्येति महासंज्ञासामर्थ्यात्तत्र सङ्ख्याप्रश्नविषयडतेरेव ग्रहणमित्यपि बोध्यम् ॥

(प्रत्याख्यानभाष्यम्)

अथ षट्संज्ञायां क्रियते, संख्यासंज्ञायां न करिष्यते।

"डति च" इत्यत्र संख्यासंज्ञाऽप्यनुवर्तिष्यते ॥ २५ ॥

(प्रदीपः) अथेति। तत्र संख्यासंज्ञाया अनुवर्तनादन्वर्थत्वाच्च संज्ञायाः संख्याप्रश्नविषय एव डतिर्गृह्यते, न लौणादिको डतिः ॥ २५ ॥

(उद्द्योतः) भाष्ये—डति चेत्यत्रेति। चकारात्षट्संज्ञाऽनन्तरं करणाधानेन संज्ञाद्वयस्यापि विधानमित्यर्थः ॥ अन्वर्थत्वाच्चेति। सङ्ख्यायतेऽनयेति हि सः। न च तस्यार्थस्य डत्यन्ते संभवः। सङ्ख्याप्रश्नविषयत्वं तु न तदर्थ इति चिन्त्यमेतत्। तैसादुणादीनामव्युत्पन्नत्वाच्च तत्र डतिरिति तस्याग्रहणमित्युचितम्। व्युत्पत्तावपि पातेः क्तिनाऽपि सिध्यतीति न तत्र डतिनियम इति बोध्यम् ॥ सङ्ख्याप्रश्नेति। संनियोगशिष्टन्यायाच्च षट्संज्ञाऽपि तस्यैवेति भावः ॥ २५ ॥

(२५ निष्ठासंज्ञासूत्रम् ॥ १। १। ५ आ. १४ ॥)

क्तक्तवतू निष्ठा ॥ १। १। २६ ॥

(प्रदीपः) क्तक्तवतू० ॥ २६ ॥ इहानुबन्धाः कार्यार्थमुपादीयन्ते। प्रयोगस्त्वेषां लुप्तत्वान्नास्ति। यत्र च सारूप्यं तत्र सन्देहः—कथमस्यानुबन्धकार्यं कृतमस्य तु न कृतमिति पूर्वपक्षाभिप्रायः ॥ सिद्धान्तवादी तु मन्यते—अध्रुवेणानुबन्धेन नियतसंनिधाना अर्थाः कारककालादयो लक्ष्यन्ते। तद्दर्शनादनुबन्धस्मृतौ च तल्लक्षितानां कार्याणां साधुत्वं विज्ञायते। तत्र यदा 'देवदत्तेन लूनः शालिः' इति कश्चित्प्रयुङ्क्ते, तदा लक्षणज्ञः कर्मभूतकालावगमात् क्तप्रत्ययं मन्यते। यदा तु 'लोतमालभेत' इति प्रयोगस्तदा मेषवाची लोतशब्दस्तन्प्रत्ययान्तः प्रयुक्त इति मन्यते ॥

(उद्द्योतः) क्तक्तवतू ॥ २६ ॥ अनुबन्धानां नित्यलुप्ततया विशेषणत्वासंभवादुपलक्षणत्वे च तच्छब्दमात्रस्योपलक्ष्यत्वं मन्यमानो वार्तिककारमत इत्याह—इहेति ॥ सारूप्यं-प्रयोगे इति शेषः ॥ मन्यत इति। निश्चिनोतीत्यर्थः। नियतं संनिधानं येषामिति विग्रहः ॥ कारकेति। न तच्छब्दमात्रं लक्ष्यम्, किं त्वर्थविशेषाद्यवच्छिन्नमिति भावः ॥ तद्दर्शनादिति। कालादिज्ञानादित्यर्थः ॥ तन्प्रत्ययान्त इति। ककारानुपलक्षितः प्रयुक्त इति निश्चिनोतीत्यर्थः ॥

(अनिष्टापत्तिनिराकरणाधिकरणम्)

(१८७ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ निष्ठासंज्ञायां समानशब्द-प्रतिषेधः ॥ * ॥

(भाष्यम्)

निष्ठासंज्ञायां समानशब्दानां प्रतिषेधो वक्तव्यः। लोतः, गर्त इति ॥

(१८८ आक्षेपबाधकवार्तिकम् ॥ २ ॥)

॥ * ॥ निष्ठासंज्ञायां समानशब्दा-प्रतिषेधः ॥ * ॥

(भाष्यम्)

निष्ठासंज्ञायां समानशब्दानामप्रतिषेधः। अनर्थकः प्रतिषेधः—अप्रतिषेधः ॥

(आक्षेपभाष्यम्)

निष्ठासंज्ञा कस्मान्न भवति?

(आक्षेपबाधको वार्तिकैकदेशः ॥)

अनुबन्धोऽन्यत्वकरः ॥

(भाष्यम्)

अनुबन्धः क्रियते सोऽन्यत्वं करिष्यति ॥

(१८९ आक्षेपबाधकहेतुनिराकरणवार्तिकम् ॥ ३ ॥)

॥ * ॥ अनुबन्धोऽन्यत्वकर इति चेन्न लोपात् ॥ * ॥

(भाष्यम्)

अनुबन्धोऽन्यत्वकर इति चेत्,

तन्न।

किं कारणम्?

'लोपात्'। लुप्यतेऽत्रानुबन्धः। लुप्ते चानुबन्धे नान्यत्वं भविष्यति। तद्यथा-कतरद्देवदत्तस्य गृहम्? 'अदो यत्रासौ काकः' इति, उत्पतिते काके नष्टं

तद्गृहं भवति ॥

एवमिहापि लुप्तेऽनुबन्धे नष्टः प्रत्ययो भवति ॥

(उद्द्योतः) भाष्ये—नष्टं गृहमिति । अज्ञातमित्यर्थः ॥ नष्टः प्रत्यय इति । अज्ञातानुबन्धः प्रत्ययो भवतीत्यर्थः ॥

(आक्षेपबाधकबाधकभाष्यम्)

यद्यपि लुप्यते, जानाति त्वसौ—सानुबन्धकस्येयं संज्ञा कृतेति । तद्यथा—इतरत्रापि कतरद्देवदत्तस्य गृहम्? 'अदो यत्रासौ काकः' इति, उत्पतिते काके यद्यपि नष्टं तद्गृहं भवति अन्ततस्तमुद्देशं जानाति ॥

(उद्द्योतः) सानुबन्धकस्येति । पूर्वं यः ककारवांस्तस्येत्यर्थः ॥ उद्देशम्—ऊर्ध्वदेशम् ॥

(१९० आक्षेपवार्तिकम् ॥ ४ ॥)

॥ * ॥ सिद्धविपर्यासश्च ॥ * ॥

(भाष्यम्)

सिद्धश्च विपर्यासः । यद्यपि जानाति, संदेहस्तस्य भवति—अयं स तशब्दः—लोतः—गर्त इति, अयं स तशब्दः—लूनः—शीर्ण इति । तद्यथा—इतरत्रापि कतरद्देवदत्तगृहम्? अदो यत्रासौ काकः—इति उत्पतिते काके यद्यपि तमुद्देशं जानाति संदेहस्तु तस्य भवति—इदं तद्गृहं—इदं तद्गृहमिति ॥

(प्रदीपः) सिद्धविपर्यास इति । सिद्धो विपर्यासः, संशय इत्यर्थः ॥ इदं तद्गृहमिति । बुद्धेरनवस्थितत्वमनेन प्रतिपाद्यते । न त्वेतद्विर्वचनं, वीप्साद्यर्थाभावात् ॥

(उद्द्योतः) सिद्धविपर्यासश्चेति । चस्त्वर्थे । सिद्धस्तु विपर्यास इत्यर्थः ॥ यद्यपि विपर्यासो भ्रमात्मकनिश्चयस्तथाप्ययथार्थत्वसाम्यादिह संशयोऽभिप्रेत इत्याह—संशय इति ॥ बुद्धेरनवस्थितत्वमिति । सन्देहाभिनय इत्यर्थः ॥ वीप्सादीति । पदार्थविषयव्याप्तीच्छा प्रयोक्तृधर्मो हि वीप्सेति भावः ॥

(आक्षेपनिराकरणभाष्यम्)

एवं तर्हि—

(समाधाने भाष्यवार्तिकम्)

कारककालविशेषात् सिद्धम् ॥

(भाष्यम्)

कारककालविशेषावुपादेयौ । भूते यस्तशब्दः कर्तरि कर्मणि भावे चेति । तद्यथा—इतरत्रापि य एष मनुष्यः प्रेक्षापूर्वकारी भवति सोऽध्रुवेण निमित्तेन ध्रुवं निमित्तमुपादत्ते—वेदिकां पुण्डरीकं वा ॥

(उद्द्योतः) भाष्ये—कारकेति—कालातिरिक्तप्रत्ययार्थपरम् ॥ वेदिकां पुण्डरीकं चेति—भाष्ये । एवं च साक्षादितरव्यावर्तकं विशेषणम् । स्वोपस्थाप्यार्थद्वारा इतरव्यावर्तकमुपलक्षणमिति भावः ॥

(आक्षेपभाष्यम्)

एवमपि 'प्राकीर्ष्ट' इत्यत्र प्राप्नोति ॥

(प्रदीपः) प्राकीर्ष्टेति । अत्र भूतकालोऽस्तीति भावः ॥

(उद्द्योतः) प्राकीर्ष्टेति । यद्यप्यत्र निघातप्रवृत्तेर्न निष्ठास्वकृतो विशेषस्तथापि 'यन्मा प्रकीर्ष्ट' इत्यस्योपलक्षणमिदम् । अत्र हि निपातैर्यद्यदीति निघाते निषिद्धे निष्ठा च द्व्यजनादिति नित्यमाद्युदात्तत्वं स्यात् । असंज्ञायामपि तत्प्रवृत्तिं मन्यते । आदिः सिच इति विकल्पस्त्विष्यत इति भावः ॥

(१९१ समाधानवार्तिकम् ॥ ५ ॥)

॥ * ॥ लुङि सिजादिदर्शनात् ॥ * ॥

(भाष्यम्)

लुङि सिजादिदर्शनाच्च भविष्यति ॥

(आक्षेपभाष्यम्)

यत्र तर्हि सिजादयो न दृश्यन्ते—प्राभित्त—इति ॥

(समाधानभाष्यम्)

दृश्यन्तेऽत्रापि सिजादयः ।

किं वक्तव्यमेतत्?

न हि ।

कथमनुच्यमानं गंस्यते?

यथैवायमनुपदिष्टान् कारककालविशेषानवगच्छति एवमेतदप्यवगन्तुमर्हति—यत्र सिजादयो नेति ॥ २६ ॥

इति श्रीमद्भगवत्पतञ्जलिविरचिते व्याकरणमहाभाष्ये प्रथमस्याध्यायस्य प्रथमे पादे पञ्चममाह्निकम् ॥

(प्रदीपः) दृश्यन्तेऽत्रेति । 'सिजादि' इति आदिशब्दः प्रकारे । तत्र 'प्राभित्त घटं देवदत्तः' इति प्रयोगे कर्त्रैकत्वाद्यवगमाल्लुङन्तस्यायं प्रयोगः, न निष्ठान्तस्येति प्रतिपद्यन्ते । 'अञ्जिघृषिभ्यः क्तः' इत्यस्य निष्ठासंज्ञा न भवति, उणादीनामव्युत्पन्नत्वाद्बाहुलकाद्वा । अन्यथा 'निष्ठा च द्व्यजनात्' इत्याद्युदात्तत्वं स्यात् ॥ २६ ॥

इत्युपाध्यायजैयटपुत्रकैयटकृते महाभाष्यप्रदीपे प्रथमस्याध्यायस्य प्रथमे पादे पञ्चममाह्निकम् ॥

(उद्द्योतः) सिचोऽत्र लुप्तत्वेनादर्शनादाह—आदिशब्द इति ॥ अञ्जिघृषीति । यद्यप्यत्रोपलक्ष्यकालकारकाद्यभावस्तथापि गुणाभावदर्शनात् कोऽयमित्यवगतिः । एवं च सनादिविधावित्संज्ञकनकारोपलक्षितः प्रकृत्यर्थानुवादी इच्छार्थो वा सकारो भवतीत्यर्थः । अनुवादे सन्यत इत्यादौ तादृशनकारोपलक्षिते सकारे इत्यर्थः । अत एवाटश्चेत्यादेः सार्थक्यम् । अन्यथा यत्र सूत्रे आट्, न तत्र वृद्धिरिष्यते; यत्र चेष्यते प्रयोगे, न तत्राडिति तद्वैयर्थ्यं स्पष्टमेवेति सर्वमवदातम् ॥ २५ ॥

इति श्रीशिवभट्टसुतसतीगर्भजनागोजीभट्टकृते भाष्यप्रदीपोद्द्योते प्रथमाध्यायस्य प्रथमे पादे पञ्चममाह्निकम् ॥

अथ प्रथमाध्यायस्य प्रथमपादे षष्ठमाह्निकम् ।

(अथ सर्वनामसंज्ञाप्रकरणम्)

(२६ सर्वनामसंज्ञासूत्रम् ॥ १ । १ । २७ आ. ६)

सर्वादीनि सर्वनामानि ॥१।१।२७॥

(तद्गुणाधिकरणम्)

(पूर्वपक्षिभाष्यम्)

'सर्वादीनि' इति कोऽयं समासः?

(प्रदीपः) सर्वादीनि सर्व० ॥२७॥ कोऽयमिति । ननु नपुंसकबहुवचननिर्देशादेव बहुव्रीहिनिश्चयात्समासान्तराशङ्का नैवास्तीति प्रश्नानुपपत्तिः । एवं तर्हि किमयं बहुव्रीहिरेव-आहोस्विद्बहुव्रीहितत्पुरुषयोरेकशेषः । यथा–'कतन्तेभ्यः कण्वादिभ्यश्च' इति प्रश्नः ॥ तत्र सारूप्यार्थं सर्वश्चासावादिः सर्वादिरित्यत्रादिशब्द उपादीयते, न त्वस्य प्रयोजनान्तरमस्ति । तत्र 'नपुंसकमनपुंसकेन–' इति वा '*स्वरभिन्नानां यस्योत्तरस्वरविधिः स शिष्यते*' इति वा बहुव्रीहेः शेषः ॥

(उद्द्योतः) सर्वादी ॥ २७ ॥ नन्विति । आदिशब्दस्य नित्यपुंस्त्वेन एकवचनान्तत्वेन च समासान्तरे नपुंसकत्वबहुत्वानुपपत्तेरिति भावः ॥ प्रकृते तत्पुरुषः कर्मधारयः, दृष्टान्ते षष्ठीतत्पुरुषः ॥ न त्वस्येति । कर्मधारयघटकस्येत्यर्थः ॥ बहुव्रीहेरेव शेषे युक्तिमाह— तत्र नपुंसकमिति । तत्पुरुषस्तु पुंल्लिङ्ग इति भावः ॥ स्वरभिन्नानामिति । स्वरेण विलक्षणानां सरूपाणां मध्ये उत्तरसूत्रेण यस्य स्वरविधिरित्यर्थः । कर्मधारयः समासस्येत्यन्तोदात्तः । परस्तु बहुव्रीहौ प्रकृत्येति परशास्त्रेणान्तोदात्तपूर्वपद इति बोध्यम् । तत्राद्ये सर्वशब्दस्य संज्ञा न प्राप्नोति, अन्त्ये तु सिध्यतीति विशेषः ।

(समाधानभाष्यम्)

बहुव्रीहिरित्याह ॥

(प्रदीपः) वक्ष्यमाणेन न्यायेन विनाऽप्येकशेषेण सर्वशब्दस्य संज्ञा सिध्यतीति मत्वाऽऽह—बहुव्रीहिरिति ॥

(उद्द्योतः) वक्ष्यमाणेन–तद्गुणसंविज्ञानेन ॥

(अनुयोगभाष्यम्)

कोऽस्य विग्रहः?

(प्रदीपः) एवमपि संदेहः । किं प्राथमकल्पिको बहुव्रीहिः, अथ बहुव्रीहितत्पुरुषयोरेकशेषे बहुव्रीहिरिति पृच्छति—कोऽस्येति ॥

(उद्द्योतः) प्राथमकल्पिकः—एकशेषनिरपेक्षत्वेन प्रथमप्रतीतः ॥ वक्ष्यमाणन्यायानभिज्ञस्य प्रश्न इति भावः ॥

(समाधानभाष्यम्)

सर्वशब्द आदिर्येषां तानि–इमानीति ॥

यद्येवं सर्वशब्दस्य सर्वनामसंज्ञा न प्राप्नोति ।

किं कारणम्?

अन्यपदार्थत्वाद्बहुव्रीहेः ।

बहुव्रीहिरयमन्यपदार्थे वर्तते, तेन यदन्यत्सर्वशब्दात्तस्य सर्वनामसंज्ञा प्राप्नोति । तद्यथा–'चित्रगुरानीयताम्' इत्युक्ते यस्य ता गावो भवन्ति स आनीयते, न गावः ॥

नैष दोषः, भवति हि बहुव्रीहौ तद्गुणसंविज्ञानमपि । तद्यथा–'चित्रवाससमानय' 'लोहितोष्णीषा ऋत्विजः प्रचरन्ति' । तद्गुण आनीयते, तद्गुणाश्च प्रचरन्ति ॥

(प्रदीपः) तानीमानीति । अन्यपदार्थस्य प्राधान्यं प्रदर्श्यते । अन्यथा यथा–चित्रा गावोऽस्येति गवां विशेष्यत्वं तद्वतश्च विशेषणत्वमवगम्यते, तथेहाप्यवगम्येत । अत्र चार्थे बहुव्रीहिर्नेष्यते । यदा तु स्वामिनः प्राधान्यं गवां विशेषणभावस्तदा बहुव्रीहिः । अत एव चित्रा गावो यस्य स चित्रगुरिति स्वामिनः प्राधान्यं प्रदर्श्यते । 'तानीमानि' इति सर्वनामद्वयोपादानेन प्रत्यक्षविषयत्वादिदंशब्दस्य गणपठितेषु सर्वशब्दस्यान्तर्भावात्तद्गुणसंविज्ञानं सूचयति । तस्यान्यपदार्थस्य गुणा उपलक्षणानि तेषामपि कार्ये संविज्ञानं–तद्गुणसंविज्ञानम् । तत्र चित्रगुरानीयतामिति स्वस्वामिभावसंबन्धः षष्ठ्यर्थ इति स्वविशेषोपलक्षितस्य स्वामिन एवानयनं, न तु गवाम् । 'दण्डी विषाणी चानीयताम्' इत्यत्र संयोगसमवायलक्षणेन संबन्धेन संबन्धिनि कार्ये विज्ञायमान उपलक्षणस्याप्यन्तर्भावो भवति । इहाप्यादिशब्दस्यावयववाचित्वादुद्भूतावयवभेदः समुदायः समासार्थः । तस्य च समुदायस्य युगपत्कृत्स्ने प्रयोगाभावात्तदन्तर्भूतानामेव पृथक् प्रयोगसत्वात्कार्याथया संज्ञया प्रवर्तितव्यमिति सर्वशब्दस्यापि सा सिध्यति । यथा–'देवदत्तशालायां ब्राह्मणा आनीयन्ताम्' इत्युक्ते देवदत्तोऽपि यदि ब्राह्मणो भवति स्वशालास्थश्च तदा सोऽप्यानीयत एव ॥

(उद्द्योतः) विग्रहप्रश्नोत्तरे 'तानि' इत्याद्यधिककथनमयुक्तमत आह—अन्यपदार्थस्येति ॥ नेष्यत इति । प्रथमान्तानामन्यपदार्थप्राधान्ये बहुव्रीहिविधानादिति भावः ॥ नन्वेवमपि 'तानि' इत्येव सिद्धे 'इमानि' इति व्यर्थमत आह—सर्वनामद्वयेति । सर्वनामद्वयोपादानेन तद्गुणसंविज्ञानं सूचयतीत्यन्वयः ॥ प्रत्यक्षेति । उद्भूतावयवभेदस्य गणपठितस्य समुदायस्येदमा परामर्शात् तत्र च सर्वशब्दस्यान्तर्भावादिति भावः ॥ गुणत्वं दर्शयति—उपलक्षणानीति । प्रकारतयाऽन्वयीनीत्यर्थः ॥ कार्ये संविज्ञानमिति । तच्च द्वेधा । क्वचित् विशिष्टस्य क्रियायां संनिधानमात्रेण, यथा—क्रियायोगाभावेऽपि शुक्लवाससं भोजयेति । क्वचित्तु विशेषणस्यापि क्रियायोगेन, यथा—शुक्लवाससं पश्येति । कार्ये यत्र तद्भावभावि तत्र तद्गुणत्वमित्यर्थः फलितः । एवं तद्गुणसंविज्ञाने तद्विशिष्टस्येतरान्वयः, अन्यत्र तदुपलक्षितस्य–इत्यपि भेदः ॥ अयं शब्दशक्तिस्वभावगम्योऽन्तर्भावः-कार्यित्वं कार्यसंनिहितत्वं वा । एवंच यत्र संयोगसमवायान्यतरसंबन्धेन संबन्ध्यन्यपदार्थस्तत्र तद्गुणः, अन्यत्रातद्गुण इत्युत्सर्ग इति गोलार्धः ॥ ननु प्रकृते न संयोगो नापि समवाय इत्यत आह—इहापीति । एवं च समवायेन संबन्धिनोऽन्यपदार्थत्वेन तद्गुणत्वमेवोचितमित्यर्थः ॥ बहुवचनोपपत्तय आह—उद्भूतावयवभेद इति । अवयवगतसंख्यारोपेण बहुवचनमिति भावः ॥ नन्वेवं समुदायस्यैव संज्ञा स्यादत आह—तस्य चेति । युगपत्प्रयोगाभावात् पृथक्प्रयोगसत्वाच्च कार्यार्थया संज्ञया तदन्तर्भूतानामेव प्रवर्तितव्यमित्यन्वयः ॥ 'पृथक्प्रयोगसत्वात्' इति पाठे बहुव्रीहेस्त्वो बोध्यः ॥ सिध्यतीति । विनिगमनाविरहादिति भावः ॥ नन्वेवं सर्वशब्दस्य संबन्धविशेष्यस्वा-

भावात्कथं तस्य सर्वनामत्वमत आह—यथेति । स्वरूपेणोपलक्षणमपि सर्वशब्दः समुदायान्तर्भूततया संबन्धविशेष्योऽपि । यथा–देवदत्तत्वेन विशेषणमपि देवदत्तो ब्राह्मणत्वेन विशेष्य इति भावः ॥ अन्यपदार्थत्वादिति भाष्यस्य–अन्यः पदार्थो यस्य तत्त्वादित्यर्थः ॥

(सर्वनामपदसाधुत्वाधिकरणम्)

(शङ्काभाष्यम्)

इह 'सर्वनामानि' इति "पूर्वपदात्संज्ञायामगः" इति णत्वं प्राप्नोति, तस्य प्रतिषेधो वक्तव्यः ॥

(प्रदीपः) **णत्वं प्राप्नोतीति** । राजपुरुषादिवत्संज्ञाशब्दा अपि शास्त्रप्रक्रियायां सन्तमसन्तं वाऽवयवार्थमाश्रित्य व्युत्पाद्यन्त इति णत्वप्रसङ्गः । प्रयोगे च सणत्वा अणत्वाश्च नित्या एव शब्दाः । तत्र संज्ञायां सणत्वा एव साधवः, असंज्ञायां त्वणत्वा एवेति शास्त्रव्यापाराण्णत्वं प्राप्नोत्येव । सर्वार्थाभिधानयोग्यस्य शब्दस्य शक्तिनियमनमात्रं संज्ञाकरणमिति शब्दार्थसंबन्धनित्यत्वस्यापि न विरोधः ॥

(उद्द्योतः) ननु सर्वनामशब्दो यदि व्युत्पन्नस्तदा संज्ञोपसर्जनप्रतिषेधवार्तिकारम्भानुपपत्तिः, नो चेत्पूर्वोत्तरपदविभागाभावात् पूर्वपदादिति णत्वाप्राप्तिरत आह—राजेति । सन्तं–अन्वर्थसंज्ञायाम् ॥ असन्तं–शुद्धरूढे रथन्तरादौ ॥ आश्रित्येति । द्वितीयेविषये 'आरोप्य' इत्यर्थकम् । सामविशेषे रथकरणकतरणकर्तृत्वमारोप्य साधुत्वान्वाख्यानं यथा तथा सर्वार्थवाचकत्वरूपार्थमारोप्य प्रकृतेऽपीति न वार्तिकानुपपत्तिः, नापि णत्वाप्राप्तिरिति भावः ॥ ननु शब्दनित्यताविरोधात्कथमसतो णत्वस्यापादनमत आह—प्रयोगे चेति ॥ ननु संज्ञा चेत्कृत्रिमा तदा शब्दार्थसंबन्धनित्यताहानिः, असंज्ञा चेन्न णत्वप्राप्तिरत आह—सर्वार्थेति ॥ शक्तिनियमनं–शक्तिसंबन्धबोधनमेवेत्याहुः ॥ न च 'भूवोऽसंज्ञायां' इति सूत्रे भाष्ये–"यदेतत्संज्ञायां विधीयते तत्र न संज्ञायामभिधेयायामित्यर्थः, किं तर्हि ? तत्तत्कार्यविशिष्टेन चेत्संज्ञा गम्यत इत्यर्थः" इति वक्ष्यते, ततश्चात्र कथं णत्वप्राप्तिः ? न हि कृतणत्वेन संज्ञाऽवगतिः । अत एव रघुनाथादिशब्दे न णत्वमिति वाच्यम् ॥ आधुनिकविनियोगस्थले शास्त्रानुगतस्यैव विनियोग उचित इत्याशयात् । अत एव महत्याः संज्ञायाः करणे एतत्प्रयोजनमिति वक्ष्यमाणं सङ्गच्छते । अनादिविनियुक्तसंज्ञास्थले तु यथाविनियुक्तानामेव साधुत्वमिति रघुनाथादौ णत्वाभावोऽध्वपरिमाणसंज्ञाभूतगव्यूतिशब्दे च न यलोपः, संज्ञात्वप्राप्तेरिति दिक् ॥

(१९२ समाधानवार्तिकम् ॥ ६ ॥)

॥ * ॥ सर्वनामसंज्ञायां निपातनाण्णत्वाभावः ॥ * ॥

(भाष्यम्)

सर्वनामसंज्ञायां निपातनाण्णत्वं न भविष्यति ॥

(प्रदीपः) **निपातनादिति** । लोकेऽप्ययं णत्वरहित एव प्रयुज्यते, तस्यात्र प्रसङ्गेन साधुत्वं प्रतिपाद्यते ॥

(उद्द्योतः) सौत्रत्वादित्येव कुतो नोक्तमत आह—लोक इति ॥

(आक्षेपभाष्यम्)

किमेतन्निपातनं नाम?

(प्रदीपः) **किमेतदिति** । भवतु अस्य साधुत्वं, णत्वप्रतिषेधे त्वस्य तात्पर्याभावाद्विकल्पः प्राप्नोतीति भावः ॥

(प्रतिबन्दीभाष्यम्)

अथ कः प्रतिषेधो नाम?

(प्रदीपः) इतरः प्रतिषेधेन साम्यं प्रतिपादयितुं पर्यनुयुङ्क्ते—अथ क इति ॥

(प्रतिषेधप्रतिपादकभाष्यम्)

अविशेषेण किंचिदुक्त्वा विशेषेण 'न' इत्युच्यते, तत्र व्यक्तमाचार्यस्याभिप्रायो गम्यते—'इदं न भवति' इति ॥

(निपातनप्रतिपादकभाष्यम्)

निपातनमप्येवंजातीयकमेव । अविशेषेण णत्वमुक्त्वा विशेषेण निपातनं क्रियते, तत्र व्यक्तमाचार्यस्याभिप्रायो गम्यते —'इदं न भवति' इति ॥

(प्रदीपः) सर्वत्रैवाप्राप्त्यनुमानं बाधः । निपातनं चापि णत्वाप्राप्त्यनुमानमिति भावः ॥

(उद्द्योतः) साम्यं दर्शयति—**सर्वत्रैवेति** ॥ **निपातनं चेति** । भावाभावयोरेकत्र विरोधादिति भावः ॥

(आक्षेपभाष्यम्)

ननु च निपातनाच्चाणत्वं स्यात्, यथाप्राप्तं च णत्वम् ॥

(प्रदीपः) **ननु चेति** । प्रतिषेधस्य हि निवृत्तावेव तात्पर्यम्, निपातनस्य तु तद्रूपसाधुत्वप्रतिपादने, न तु रूपान्तरनिवृत्ताविति भावः ॥

(उद्द्योतः) न त्विति । प्रयोगभेदेन च भावाभावविरोधपरिहार इति भावः ॥

(प्रतिबन्दीभाष्यम्)

किमन्येऽप्येवं विषयः?

(उद्द्योतः) भाष्ये–किमन्येऽपीति । अन्येऽपि विषयः किमेवं–एवंजातीया इति वक्ष्यमाणाभिप्रायेण प्रश्नः ॥

(प्रतिबन्द्युत्तरभाष्यम्)

भवन्ति ॥

(उद्द्योतः) आशयानभिज्ञ उत्तरयति—भवन्तीति । यथा स्थानिवदादेश इत्येतद्विषये स्थानिप्रयुक्तं भवति, यथाप्राप्तस्यादेशप्रयुक्तस्य न निवृत्तिरिति भावः ॥

(आक्षेपभाष्यम्)

इह–"इको यणचि" इति वचनात् यण् स्यात् । यथाप्राप्तश्चेक् श्रूयेत ॥

(प्रदीपः) **इको यणचीति** । यणो हि साधुत्वं प्रतिपाद्यते, न त्विङ्निवृत्तिरित्यर्थः ॥

(उद्द्योतः) शङ्कते—इको यणिति । अस्य यदि भवन्ती- त्यादिः ॥

(समाधानभाष्यम्)

नैष दोषः । अस्त्यत्र विशेषः । षष्ठ्याऽत्र निर्देशः क्रियते । षष्ठी च पुनः स्थानिनं निवर्तयति ॥

(प्रदीपः) षष्ठ्याऽत्रेति । ततश्च संहिताविषये स्वाभा- विकोऽप्रयोग इकः षष्ठीनिर्देशेन प्रतिपाद्यते । यथा—'दर्भाणां स्थाने शरैः प्रस्तरितव्यम्' इति, न तत्र दर्भाः प्रस्तीर्यन्ते ॥

(उद्द्योतः) ततश्च संहितेति । स्थानिनो निवृत्तिर्नाम तत्साधुत्वबुद्धेर्निवृत्तिः । सा च संहितायां शाकलाभावे-इति भावः ॥ प्रस्तीर्यन्त इति । किन्तु तत्प्रसङ्गे शराः प्रस्तीर्यन्त इति शेषः । तथा च स्थानषष्ठीनिर्देशे उभयत्रापि तात्पर्यमिति भावः ॥

(आक्षेपभाष्यम्)

इह तर्हि—"कर्तरि शप्" "दिवादिभ्यः श्यन्" इति वचनाच्च श्यन् स्यात् । यथाप्राप्तश्च शप् श्रूयेत ॥

(प्रदीपः) इह तर्हीति । विकल्पः प्राप्नोतीति भावः । समुच्चयस्तु न भवति, एकेन परदेशस्यावष्टब्धत्वाद्धातुसार्वधा- तुकयोश्चार्थाभिधाने एकेनैव साहायकस्य संपादनात् ॥

(उद्द्योतः) विकल्प इति । स्थानषष्ठ्यभावेनोभयत्र तात्पर्या- भावादिति भावः ॥ परदेशस्येति । विकरणविधौ 'धातोः' 'परश्च' इत्यधिकारेण धातोः परो विकरणः प्रयोक्तव्य इत्यर्थादिति भावः ॥ ननु धातोः परो विधातव्य इत्यर्थे पूर्वं श्यनि विहिते पश्चाच्छबपि स्यात्, तिङ्विकरणवत् । 'सार्वधातुके' इति च विषयसप्तमी स्यादत आह—धात्विति ॥ साहायकं-सहायकार्यम् ॥

(समाधानभाष्यम्)

नैष दोषः । शबादेशाः श्यनादयः करिष्यन्ते ॥

(प्रदीपः) शबादेशा इति । श्यनश्च शित्करणं ज्ञाप- कम्—स्थानिवद्भावाभावस्य । तेन 'करोति' इत्युप्रत्ययस्यापित्त्वा- दनुदात्तत्वं न भवति । 'कुर्वती' इत्यत्र 'शप्श्यनोर्नित्यम्' इति नुमागमो न भवति, 'आत्' इत्यधिकाराद्वा । 'रुधादिभ्यः श्नम्' इत्यत्र रुधादीनां श्रुतत्वात्तेषामेवान्त्यादचः परः श्नम् भवति, न तु शपः । यथा च-'भ्रस्जो रोपधयो रमन्यतरस्याम्' इति रमागमो रोपधयोर्निवर्तकः, एवं शपः श्नम् ॥

(उद्द्योतः) ननु श्यन्नादीनामादेशत्वे स्थानिवद्भावात्पित्त्वे करोतीत्यादौ विकरणस्यानुदात्तत्वं स्यात् । न च सति शिष्टस्वरबली- यस्त्वस्य विकरणान्यविषयत्वेनोप्रत्ययस्य कथमुदात्तत्वं सिद्धान्तेऽपीति वाच्यम् । सार्वधातुकस्वरापेक्षयैव विकरणस्वरस्य तेन दुर्बलत्वकथना- दत आह—श्यनश्च शित्करणमिति । न च शित्त्वं नियमार्थं स्यात्—शिदेव न पिदिति । शित्त्वस्य नियमार्थत्वकल्पनापेक्षयाऽति- देशबाधकत्वस्यैवौचित्यात् । अतिदेशबाधश्च तवाप्यावश्यक एव ॥ क्वचित्तु 'तिरस्करणं' इति पाठः ॥ तद्धि प्रत्ययाद्युदात्तत्वबाधेन छिनतीत्यनेन निदन्तस्याद्युदात्तत्वाय । स्थानिवत्त्वात्पित्त्वेनानुदात्तत्वे तु लसार्वधातु- कस्यापि अदुपदेशादित्यनुदात्तत्वे धातोरुदात्तत्वं सिद्धमेवेति तदर्थं सद् ज्ञापकमिति भावः ॥ परं त्वयं पाठः स्थानिवत्सूत्रस्थकैयटविरुद्धः ॥ आदित्यधिकाराद्वेति । तुदतीत्यादौ नित्यनुम्व्यावृत्तये पूर्वोक्त- समाधिरेवावश्यकः ॥ 'शप्श्यनोः–' इति सूत्रस्थश्यन्ग्रहणमप्युक्तार्थे ज्ञापकमिति बोध्यम् ॥ नन्वेवं शपः परः श्नम् स्यादत आह— रुधादिभ्य इति । 'सार्वधातुके' इति सप्तम्या 'रुधादिभ्यः' इति पञ्चम्याः षष्ठीकल्पनात्तेषामेवान्त्यादचः परः श्नमिति भावः ॥ तृणह इति निर्देशश्च रुधादीनामागमित्वे लिङ्गम् ॥ नन्वेवं शपः श्रवणं स्यादत आह—यथा चेति । शप इत्यस्य षष्ठीकल्पनसामर्थ्यादिति भावः ॥

(आक्षेपभाष्यम्)

तत्तर्हि शपो ग्रहणं कर्तव्यम् ?

(आक्षेपबाधकभाष्यम्)

न कर्तव्यम् । प्रकृतमनुवर्तते ॥

क्व प्रकृतम् ?

"कर्तरि शप्" इति ॥

(आक्षेपसाधकभाष्यम्)

तद्वै प्रथमानिर्दिष्टम्, षष्ठीनिर्दिष्टेन चेहार्थः ॥

(आक्षेपबाधकभाष्यम्)

'दिवादिभ्यः' इत्येषा पञ्चमी 'शप्' इति प्रथमायाः षष्ठीं प्रकल्पयिष्यति "तस्मादित्युत्तरस्य" इति ॥

(आक्षेपसाधकभाष्यम्)

प्रत्ययविधिरयम् । न च प्रत्ययविधौ पञ्चम्यः प्रकल्पिका भवन्ति ॥

(आक्षेपबाधकभाष्यम्)

नायं प्रत्ययविधिः । विहितः प्रत्ययः प्रकृतश्चा- नुवर्तते ॥

(उद्द्योतः) भाष्ये—विहितः प्रत्यय इति । शब्रूपः प्रत्यय इत्यर्थः ॥

(आक्षेपभाष्यम्)

इह तर्हि—"अव्ययसर्वनाम्नामकच् प्राक् टेः" इति वचनाच्चाकच् स्यात् । यथाप्राप्तश्च कः श्रूयेत ॥

(प्रदीपः) इह तर्हीति । देशभेदाद्विरोधाभावेऽपि काकचोरेकार्थत्वाद्विकल्प एव चोद्यते, न समुच्चयः ॥

(उद्द्योतः) एकार्थत्वादिति । अज्ञातादेरेकेन द्योतितत्वान्न द्वयोः समुच्चय इति भावः ॥

(समाधानभाष्यम्)

नैष दोषः । नाप्राप्ते हि केऽकजारभ्यते, स बा- धको भविष्यति ॥

(उपसंहारभाष्यम्)

निपातनमप्येवंजातीयकमेव । नाप्राप्ते णत्वे नि- पातनमारभ्यते, तद्बाधकं भविष्यति ॥

(उद्योतः) येन नाप्राप्तिन्यायेनाकज्जादीनां बाधकत्वे परे-णोक्ते सिद्धान्ती तेनैव न्यायेन निपातनानामपि बाधकत्वमेवेत्याह—निपातनमपीति ॥

(आक्षेपभाष्यम्)

यदि तर्हि निपातनान्यप्येवंजातीयकानि भवन्ति, समस्तते दोषो भवति ॥

इहान्ये वैयाकरणाः समस्तते विभाषा लोपमारभन्ते—"समो हिततततयोर्वा" इति । सततम्-संततम्, सहितम्-संहितमिति ॥

इह पुनर्भवान्निपातनाल्लोपमिच्छति—"अपरस्पराः क्रियासातत्ये" इति । यथाप्राप्तं चालोपम्—संततमिति, एतन्न सिध्यति ॥

(उद्योतः) भाष्ये—एतदिति । 'सततं' 'सन्ततं' इत्युभयमित्यर्थः ॥

(सिद्धान्तिसमाधानभाष्यम्)

कर्तव्योऽत्र यत्नः । बाधकान्येव हि निपातनानि भवन्ति ॥

(प्रदीपः) कर्तव्योऽत्र यत्न इति । "लुम्पेदवश्यमः" इत्ययं श्लोकोऽन्यार्थमवश्यं पठितव्यः । तेनैव 'सततं' 'सन्ततम्' इति च सिध्यति, न तु निपातनेनेत्यर्थः । 'सांतत्यम्' इति चानभिधानात् ष्यञन्तस्य प्रयोगाभावः । पुराणशब्देन पुरातनशब्दस्य बाधः प्राप्तः पृषोदरादित्वान्न भवति ॥

(उद्योतः) श्लोकोऽन्यार्थमवश्यमिति । एकदेशानुमतिद्वारा 'सातत्ये' इति निर्देशेन स एव श्लोको ज्ञाप्यते—इत्यर्थः ॥ न त्विति । निपातनेन 'सततं' इति न साध्यत इत्यर्थः ॥ नन्वेवं सन्ततात्ष्यञि सान्तत्यमित्यपि स्यादत आह—इति चानभिधानादिति । अत एव भगवता 'सन्ततमिति न सिध्यति' इत्येवोक्तं न तु सूत्रोच्चारितसजातीयं सान्तत्यमिति न सिध्यतीत्युक्तम् ॥ पुराणशब्देनेति । 'पुराणप्रोक्तेषु—' इत्यत्र निपातितेनेत्यर्थः ॥ पृषोदरादित्वादिति । एवं च तेनैवोभयोरपि साधुत्वम्, न तु निपातनेनेति भावः ॥

(संज्ञोपसर्जनाधिकरणम्)

(१९३ आक्षेपवार्तिकम् ॥ ७ ॥)

॥ * ॥ संज्ञोपसर्जनप्रतिषेधः ॥ * ॥

(भाष्यम्)

संज्ञोपसर्जनीभूतानां सर्वादीनां प्रतिषेधो वक्तव्यः । सर्वो नाम कश्चित्, तस्मै-सर्वाय देहि । अतिसर्वाय देहि ॥

(प्रदीपः) संज्ञोपसर्जनीभूतानामिति । ये विषयान्तरे दृष्टास्त एवेमामवस्थां प्राप्ता इति विवक्षया च्विप्रत्ययनिर्देशः ॥ सर्वाय देहीति । पदकार्येषु गौणमुख्यन्यायो न प्रातिपदिककार्येष्विति 'शब्दाश्रये च वृद्ध्यात्वे' इत्यत्रोक्तमिति प्रसिध्यप्रसिद्धिबलात्संभवत्यपीह स नोक्तः । * समासकृत्तद्धिताव्ययसर्वनामासर्वलिङ्गा जातिरेकद्रव्योपनिवेशिनी संज्ञा * इत्येतदनपेक्ष्य संज्ञाप्रतिषेधः । तत्र ह्यपेक्षिते परया पूर्वा संज्ञा बाध्यत इति संज्ञासंज्ञया सर्वनामसंज्ञाबाधनात्प्रसङ्गाभावः ॥ अतिसर्वायेति । प्रादिसमासोऽयं, बहुव्रीहौ संज्ञाप्रतिषेधात् । 'प्रयोजनं सर्वनामाव्ययसंज्ञायाम्' इति तदन्तविधिः 'परमसर्वस्मै' इत्याद्यर्थं आश्रितः ॥

(उद्योतः) च्विप्रत्ययेति । गणपठितेभ्यः संज्ञोपसर्जनानां भेदात्संज्ञाया अप्राप्तौ प्रतिषेधानर्थक्यमिति शङ्काव्युदासाय भाष्ये च्विरूपात्त इति भावः ॥ तत्तत्पदत्वारोपवत् तदर्थे उपसर्जनत्वमप्यारोपितमिति च्वेरुपपत्तिरिति तात्पर्यम् ॥ पदकार्येष्विति । न च संज्ञा तथेति भावः ॥ इदमेव वार्तिकं तस्य न्यायस्य पदकार्यविषयत्वे लिङ्गमिति तात्पर्यम् ॥ अत एवाभिव्यक्तपदार्था ये इति न्यायस्याप्यत्राप्रवृत्तिरिति बोध्यम् ॥ अत्र न गुणयोगेन लाक्षणिकत्वरूपं गौणत्वमत आह—प्रसिद्धीति । तन्मूलं प्रसिद्धत्वादिकमत्रापि तुल्यमित्यर्थः ॥ समासेति । अनेन क्रमेणैताः संज्ञा एकसंज्ञाधिकारे कार्या इति वक्ष्यत्याकडारसूत्रे । तदनपेक्ष्यायं संज्ञाप्रतिषेध इत्यर्थः ॥ एकद्रव्योपनिवेशिनीति । लौकिकसंज्ञालक्षणम् । एतेन सर्वनामादिसंज्ञास्वनेकविषयास्विदमव्याप्तमिति परास्तम् ॥ नन्वतिसर्वस्य गणे पाठाभावात्संज्ञासूत्रे विशेष्यासन्निधानेन तदन्तविधेरभावाच्च कथमत्र प्राप्तिरत आह—प्रयोजनमिति । शब्दरूपं विशेष्यमादाय तदन्तविधिरिति भावः ॥ एतत्तदन्तविधिफलत्वेन 'परमसः' इत्यस्योपन्यासः कश्चिद्दृश्यते स चिन्त्यः, त्यदादीनाम इत्यादावङ्गविशेषणत्वमूलकतदन्तविधिना सिद्धत्वात् ॥ समासे तु विहितविशेषणमिति बोध्यम् ॥

(आक्षेपभाष्यम्)

स कथं कर्तव्यः ?

(१९४ समाधानवार्तिकम् ॥ ८ ॥)

॥ * ॥ पाठात्पर्युदासः, पठितानां संज्ञाकरणम् ॥ * ॥

(भाष्यम्)

पाठादेव पर्युदासः कर्तव्यः, शुद्धानां पठितानां संज्ञा कर्तव्या । सर्वादीनि सर्वनामसंज्ञानि भवन्ति, संज्ञोपसर्जनीभूतानि न सर्वादीनि ॥

(प्रदीपः) पाठादिति । यथा-'तिङोगोत्रादीनि' इत्यत्र कुत्सनाभीक्ष्ण्यग्रहणं गोत्रादिपाठविशेषणम्, तथेहापि सर्वादिसन्निवेशो विशेष्यते—असंज्ञोपसर्जनानि सर्वादीनि गणसन्निविष्टानि, नान्यानीत्यर्थः ॥

(उद्योतः) यथेति । यथा तत्सूत्रं निपातविधायकं वाक्यभेदेन पाठविशेषणं च, तथेहापीत्यर्थः ॥

(आक्षेपभाष्यम्)

किमविशेषेण ?

(प्रदीपः) किमविशेषेणेति । किं यत् सर्वेषां सर्वादीनां सर्वनामकार्यं तदर्थमेव-इति प्रश्नः ॥

(उद्द्योतः) यदि 'अविशेषेण' इत्यस्य सर्वकार्यार्थमित्यर्थः, तर्हि 'नेत्याह विशेषेण च' इत्युत्तरमन्यासङ्गतिरत आह— किं तर्हि सर्वेषामिति । यद्यपि सायामपि न सर्वेषां कार्यम्, उभभवदादावसंभवात्; तथाप्यन्तर्गणानाश्रयणेन विधीयमानं कार्यमिति तदर्थो बोध्यः ॥

(समाधानभाष्यम्)

नेत्याह । विशेषेण च ॥

(प्रदीपः) **विशेषेण चेति ।** चशब्दादविशेषेण चेत्यर्थः । यत् गणपाठोपलक्षितं विशिष्टं कार्यं 'त्यदादीनामः' 'अद्ड्डतरादिभ्यः' इत्यादि, तदर्थमपि पाठविशेषणमित्यर्थः ॥ यत्तु कार्यं 'युष्मदस्मद्भ्यां ङसोऽश्' इत्यादि स्वरूपमात्राश्रयं न सन्निवेशापेक्षं, तदविशेषेण भवति । तत्र हि न गणपठितयोर्युष्मदस्मदोर्निर्देशः, अपि त्वौणादिकयोः ॥

(उद्द्योतः) न संनिवेशेति । न सामान्यविशेषसंनिवेशापेक्षमित्यर्थः ॥ अविशेषेणेति । संज्ञोपसर्जनयोरपीत्यर्थः ॥ न गणेति । न गणपठितत्वाकारेणेत्यर्थः ॥

(भाष्यम्)

किं प्रयोजनम् ?

(१९५ प्रयोजनवार्तिकम् ॥ ९ ॥)

॥ * ॥ सर्वाद्यानन्तर्यकार्यार्थम् ॥ * ॥

(भाष्यम्)

सर्वादीनामानन्तर्येण यदुच्यते कार्यं तदपि संज्ञोपसर्जनीभूतानां मा भूदिति ॥

(उद्द्योतः) भाष्ये—सर्वादीनाम्–तदन्तर्भूतानां त्यदादिप्रभृतीनाम् ॥ आनन्तर्येण–आनन्तर्योपलक्षितत्यदादीनामित्यादिरूपेणेत्यर्थः ॥

(प्रश्नभाष्यम्)

किं प्रयोजनम् ?

(उद्द्योतः) किं प्रयोजनमिति । क्व प्रयोजनमित्यर्थः ॥

(१९६ प्रयोजनवार्तिकम् ॥ १० ॥)

॥*॥ प्रयोजनं डतरादीनामद्ड्भावे ॥*॥

(भाष्यम्)

डतरादीनामद्ड्भावे प्रयोजनम् । अतिक्रान्तमिदं ब्राह्मणकुलं कतरत्–अतिकतरं ब्राह्मणकुलमिति ॥

(१९७ प्रयोजनवार्तिकम् ॥ ११ ॥)

॥ * ॥ त्यदादिविधौ च ॥ * ॥

(भाष्यम्)

त्यदादिविधौ च प्रयोजनम् । अतिक्रान्तोऽयं ब्राह्मणस्तम्–अतितद् ब्राह्मण इति ॥

(संज्ञाप्रतिषेधप्रत्याख्यानभाष्यम्)

संज्ञाप्रतिषेधस्तावन्न वक्तव्यः । उपरिष्टाद्योगविभागः करिष्यते—"पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायाम्", ततः–"असंज्ञायाम्" इति । 'सर्वादीनि' इत्येवं यान्यनुक्रान्तानि असंज्ञायां तानि द्रष्टव्यानि ॥

(उद्द्योतः) असंज्ञायाम्–इति योगविभागो गणसूत्रे, नाष्टाध्यायीस्थे, तस्य जसि विभाषाविधायकत्वादिति बोध्यम् ॥ स्वमज्ञातीत्यादावपीदमनुवर्तत इति न दोषः ॥ सर्वादीनीत्येवं यानीति । सर्वादीनि शब्दरूपाणि इत्येवं सर्वविश्वेत्यादिक्रमेण यानि पञ्चत्रिंशदनुक्रान्तानि तानीत्यर्थः ॥

(उपसर्जनप्रतिषेधप्रत्याख्यानभाष्यम्)

उपसर्जनप्रतिषेधश्च न कर्तव्यः । "अनुपसर्जनात्" इत्येष योगः प्रत्याख्यायते, तमेवमभिसंभन्त्स्यामः—अनुपसर्जन-अ-अदिति ॥

किमिदम् 'अ-अत्' इति ?

अकारात्कारौ शिष्यमाणावनुपसर्जनस्य द्रष्टव्यौ ॥

(प्रदीपः) **अनुपसर्जनादिति ।** ननु प्रधानेन तदन्तविध्यर्थो योगः प्रारब्धव्यः, 'कौम्भकारेयः' इति यथा स्यादिति ॥ न च 'अण्' इति कृद्ग्रहणम्, तद्धितोऽप्यणस्तीति ॥ नैतदस्ति, 'स्त्रीप्रत्यये चानुपसर्जनेन' इति तदादिनियमाभावात् कारशब्दादपि ङीपि कुम्भकारीशब्दात् 'स्त्रीभ्यो ढक्' इति ढग्भविष्यति ॥ **अनुपसर्जन अ अदिति ।** 'सुपां सुलुक्' इति षष्ठ्या लुक् ॥

(उद्द्योतः) (भाष्ये) प्रत्याख्यायते इति । स्त्रीप्रत्ययप्रकरणस्थमपि सूत्रं तत्रानुपयुज्यमानं कार्यान्तरार्थं परिभाषारूपं ज्ञातव्यमिति भावः ॥ नन्विति । अन्यथा समासप्रत्ययविधौ तदन्तविधिप्रतिषेधाद् गृह्यमाणादेव प्रातिपदिकात्स्यात् । प्रत्ययग्रहणे च प्रत्ययग्रहणपरिभाषया प्रत्ययान्तादेव स्यान्न तु तदन्तादिति भावः ॥ अनेन चोक्तैरत्र तदन्तविधौ ज्ञापिते उपसर्जने निषेधात् प्रधान एव स फलवानिति प्रधानेनेत्युक्तम् ॥ कौम्भकारेय इति । अणन्तत्वेन कारशब्दादेव ङीपि कारीशब्दस्यैव स्त्रीप्रत्ययान्ततया तत एव स्त्रीभ्यो ढकि तस्यैव ढगङ्गत्वाद्वृद्धिः स्यात्, न कुम्भस्येति भावः ॥ तदन्तविधौ तु समुदायाद् ङीपि तत एव ढकि समुदायस्याङ्गत्वात्कुम्भशब्दे वृद्धिः सिध्यति ॥ ननु कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणात् तदन्तविध्यभावेऽपि कौम्भकारेयः सिद्धोऽत आह—न चेति । कृत एव ग्रहणे सा, न तु कृदकृद्ग्रहण इति भावः ॥ नैतदस्तीति । न च कदाचिद् कारीशब्दादपि स्यात् । कुम्भेनैकार्थीभूतस्य निष्कृष्यापत्येनान्वयाभावात् ॥ नन्वेवं कुम्भकारीत्यत्र ङीवेव न स्यात् । कुम्भेनैकार्थीभूताणन्तस्य केवलस्य स्त्रीत्वेनायोगात् । अत एव सूत्रारम्भे न कदाचिदपि कारशब्दान्ङीप् । यस्य च विशिष्टस्य स्त्रीत्वेन योगः, न तदणन्तमिति चेन्न । अमहत्पूर्वग्रहणेन तदन्तग्रहणज्ञापनात् ॥ अथैवं बहुकुरुचरेत्यादावतिप्रसङ्गवारणायायं निषेधोऽपि सार्थक इति वाच्यम् । टिड्ढाणञित्यादौ उपात्तस्य टिदादेरेव स्त्रीत्वेन विशेषणेनादोषात् । पूर्वत्र–उपात्तं तदन्तं च–स्त्रीत्वेन विशेष्यते, उत्तरत्र च–उपात्तमेवेत्यत्र व्याख्यानमेव शरणमिति वदन्ति ॥

परे तु—प्रत्याख्यायते इत्यस्य वार्तिककृतेति शेषः । *अनुपसर्जनग्रहणमनर्थकम्, प्रातिपदिकेन तदन्तविधिप्रतिषेधात्* इति हि तत्र वार्तिकम् । तद्रीत्याऽस्य तेन सिद्धिरित्याशयः ॥ अनुपसर्जनादिति किमर्थम् । बहुकुरुचरा । तदन्तविधिना प्राप्नोति । अत उत्तरं पठति—अनुपसर्जनग्रहणमनर्थकमिति तत्र भाष्यकृदवतारणेनाप्रत्याख्येयेन च तस्य वार्तिककृत्सिद्धान्तत्वप्रतीतेः ॥ यत्तु तदुत्तरं वचनद्वयम्—ज्ञापकं तु पूर्वत्र तदन्ताप्रतिषेधस्यातिधीवरी, पूर्वसूत्रनिर्देशो वाऽऽपिशला ब्राह्मणीति, तस्याचार्यदेशीयस्य । तत्राद्यस्य पूर्वत्र तदन्ताप्रतिषेधेऽपि उत्तरत्र तदन्तविध्यभावेन बहुकुरुचरादावप्राप्त्याऽस्य सार्थक्यानुपपादनाच्चदुक्तित्वम् । अन्त्यं तु स्त्रियामित्यस्याविशेषणत्वात् स्त्रियां योऽभिविहित इत्यादिना भाष्य एव दूषितम् । तेनाद्यस्यैव वार्तिककृत्सिद्धान्तत्वं बोधितम् ॥ 'इदं तर्हि प्रयोजनम् । प्रधानेन तदन्तविध्यर्थम्' इति तु तत्र भाष्यकृता स्वयं सूत्रप्रयोजनमुक्तमिति न विरोधः ॥ अयं हि तत्र भाष्याशयः—अनुपसर्जनस्त्रीप्रत्यये तदादिनियमाभावेऽपि कदाचित् कारीशब्दादपि स्यादिति पक्षे कुम्भकारेय इत्यस्यापत्तिः । यदुक्तं कुम्भेनेत्यादि, तत्तुच्छम् । निष्कृष्यापत्येनैकार्थीभावाभावेऽपि समुदायेनैकार्थीभावेऽवयवेनापि तस्यैव सत्त्वात्सामर्थ्याक्षतेः । विशिष्टसंबन्ध्यपत्ये विशेष्यसंबन्धस्याव्याहतेश्च ॥ अनभिधानेन प्रत्याख्यानं तु न चमत्कारकारि । अत एव परमगार्ग्यस्यापत्यमित्यर्थे तदेकदेशगार्ग्यशब्दात्प्रत्यये परमगार्ग्यायण इति येन विधिरिति सूत्रे भाष्ये उदाहृतमिति तत्रैव निरूपयिष्यामः ॥ नैव च तदन्तविधावपि व्यपदेशिवद्भावेन केवलादपि ङीप् दुर्वारः । अनुपसर्जनादित्येतत्सामर्थ्येन व्यपदेशिवद्भावाप्रवृत्तेः । मुख्यव्यपदेशिनोऽभावे एव तदतिदेशप्रवृत्तेश्च । नैव च स्त्रीप्रत्ययेषु तदादिनियमाभावेन कारीशब्दस्यापि स्त्रीप्रत्ययान्तत्वानपायात्तस्मादपि कदाचित् ढक् स्यादेवेति वाच्यम् । यतः प्रत्ययग्रहण इति नियमेनाधिकस्यैव व्यावृत्तिर्न न्यूनस्य । अस्य युवाऽपत्यमिः, परपत्यमित्यर्थे यञिञोश्चेति फकोऽनापत्तेः । एवं च तन्निषेधेनानेन तस्यैव संग्रहः, न तद्व्यावर्त्यस्य न्यूनस्य । अयमधिकारोऽप्यत्रार्थे ज्ञापक इत्याहुः ॥

एकपदत्वे उद्देश्यविधेयभावानुपपत्तेराह—सुपामिति ॥

(आक्षेपभाष्यम्)

यद्येवं-अतियुष्मत्-अत्यस्मत्-इति न सिध्यति ॥

(समाधानभाष्यम्)

प्रश्लिष्टनिर्देशोऽयम्-'अनुपसर्जन-अ-अ-अत्' इति । अकारान्तात् अकारात्कारौ शिष्यमाणावनुपसर्जनस्य द्रष्टव्यौ ॥

(प्रदीपः) **अ-अ-अदिति** । अकारेणाकारात्कारौ विशेष्येते । अकारात्परौ यावकारात्कारौ तावनुपसर्जनस्येत्यर्थः । पञ्चम्या अत्' इत्ययं तु युष्मदस्मद्भ्यामनकारान्ताभ्यां विधीयत इति परिभाषाऽनुपस्थानादुपसर्जनाभ्यामपि भवति । 'त्यदादीनामः' इत्ययमकारात्परस्य हलः स्थाने विधीयत इति अकारात्परोऽकारो भवतीति परिभाषोपस्थानात् 'अतितत्' इत्यत्र न भवति । एवं तु प्रियौ द्वावस्येति बहुव्रीहौ कृतेऽकारादविधानात्परिभाषाऽनुपस्थानादत्वं प्राप्नोति 'तदोः सः सा-' इति सत्वमविशेषितमित्युपसर्जनस्यापि प्राप्नोति ॥ तत्रायं समाधिः—'त्यदादीनामः' इत्यत्र त्यदादिषु परिभाषोपस्थानादनुपसर्जनानां तेषां ग्रहणम्, तत्साहचर्यात् द्विशब्दोऽपि तथाविध एव गृह्यते । सत्वविधौ च तथाविधानामेवानुवृत्तिरित्यत्रापि न दोषः ॥ 'अतिसर्वाय' इत्यादौ त्वविशेषकार्यमपरिहृतमेव ॥

(उद्द्योतः) अ-अ-अदित्यत्र अ इति लुप्तपञ्चम्यन्तं तदाह—**अकारादिति** ॥ **अकारान्तादिति** भाष्येऽन्तग्रहणं तु फलितार्थपरं यथाकथंचित्, न त्वत्र तदन्तविधिरिति भ्रमितव्यम् । विशेष्यासंनिधानात् । प्रायेण भाष्येऽपि अकारादकारात्कारावित्येव पाठः ॥ शेषे लोपस्यान्त्यलोपत्वपक्षे विधानोत्तरमकारात्परत्वसंभवादाह—विधीयत इति । तदुक्तं भाष्ये—**शिष्यमाणाविति** ॥ **अपरिहृतमेवेति** । एवं चैतदपरितोषाद्भाष्ये पक्षान्तरमिति भाव इति केचित् ॥

परे तु— इदं समाधानं **सर्वाद्यानन्तर्यकार्यार्थं प्रतिषेधो वक्तव्य** इत्यस्यैवार्थस्य । डतरादिविषये तस्य प्रधानेऽपि तदन्तेऽप्रवृत्तिरिति विशेषं बोधयन् तद्वारकयुक्त्यैवोपसर्जनेऽपि व्यावृत्तिरित्येवंरीत्या तत्फलकत्वाभावमुपसर्जनप्रतिषेधस्य बोधयितुमेकदेशी पक्षान्तरमाह—**अथवा**-इति । अन्त्यं समाधानद्वयं तु साधारणमित्याहुः ।

(एकदेशिसमाधानान्तरभाष्यम्)

अथवा-अङ्गाधिकारे यदुच्यते, गृह्यमाणविभक्तेस्तद्भवति ॥

(प्रदीपः) **गृह्यमाणविभक्तेरिति** । गृह्यमाणानां त्यदादीनां डतरादीनां च स्वार्थद्वारेण संबन्धिनी या विभक्तिस्तदर्थगतसंख्याकर्मादिवाचिनी तस्याः-इत्यर्थः ॥

(उद्द्योतः) **स्वार्थद्वारेणे**त्यादेर्विवरणं **तदर्थगते**त्यादि । गृह्यमाणविभक्तेरिति संबन्धसामान्ये षष्ठी । तेन विभक्तौ विधीयमानत्यदाद्यत्वस्यापि संग्रह इति भावः ॥

(समाधानबाधकभाष्यम्)

यद्येवम्, परमपञ्च-परमसप्त "षड्भ्यो लुक्" इति लुक् न प्राप्नोति ॥

(प्रदीपः) **यद्येवमिति** । गृह्यमाणाद्या विहिता विभक्तिरित्येवं संबन्धं मन्वानस्य प्रश्नः ॥

(उद्द्योतः) षड्भ्य इति षष्ठ्यर्थे पञ्चमीति मन्वानः शङ्कते—**यद्येवमिति** ॥

(समाधानसाधकभाष्यम्)

नैष दोषः । षट्प्रधान एष समासः ॥

(प्रदीपः) आर्थः संबन्धोऽत्र गृहीतः-इत्युत्तरेऽभिप्रायः ॥ यद्येवं, पञ्चकाः शकुनय इति कनः स्वार्थिकत्वाज्जसो लुक् प्राप्नोति । उच्यते, कनि कृते शब्दान्तरत्वान्नान्तत्वाभावान्नायं षट्संज्ञक इत्यदोषः ॥ 'युष्मदस्मद्भ्यां ङसोऽश्' इत्यत्र त्वङ्गेन विभक्तिर्विशेष्यत इत्युपसर्जनाभ्यामपि सिध्यति ॥

(उद्द्योतः) कनः-संख्यायाः संज्ञासङ्घेत्यनेन विहितस्य ॥ कनीति । कनि कृते कन्नन्त एव संख्यावाची, न प्रकृतिः । स च न नान्तः-इति षट्त्वाभावात्ततः परस्य जसो न लुगित्यर्थः ॥ षड्भ्य इति पञ्चम्येव । षड्भ्यः परयोः प्रत्यासत्त्या षडर्थगतसंख्याभिधायिनोर्लुगित्यर्थ इति भावः ॥ युष्मदित्यादिसिध्यतीत्यन्तग्रन्थोऽत्र पुनरुक्तः । अनुपदमग्रे वक्ष्यमाणत्वात् ॥

परे तु-गृह्यमाणविभक्तेरित्यस्य गृह्यमाणाद्विहितविभक्तेरित्येवार्थः । अड्विषयमेतत् । कतरान्तस्यानभिधानमभिप्रेत्य तत्राड्भाव एवेष्ट इत्यभिप्रेत्य वा ॥ तुल्यन्यायात् षड्भ्य इत्यत्रापि विहितविशेषणमेवेति तत्रातिप्रसङ्गं शङ्कते—यद्येवमिति । परमषट्त्वादेर्लोके गणनायां व्यवहाराभावेन षट्त्वाभाव इति लुगप्राप्तिरिति प्रश्नः ॥ संख्याप्रकारकसंख्येयविशेष्यकबोधजनकत्वेन विशिष्टस्यापि षट्त्वमस्त्येव । गणनायां प्रसिद्धानामेव संख्यावाचिनां ग्रहणमित्यत्र न मानमित्युत्तरम् ॥ पञ्चम्यन्तस्य स्वयुक्तसंबन्धेन विभक्त्याऽन्वयो दुरुपपादः । आवृत्तौ मानाभावश्च । षट्प्रधानः-इत्यस्य त्वदभिमतषडर्थप्रधानः, अतः समुदायोऽपि षट्संज्ञ इत्यर्थः ॥ षष्ठ्यन्तस्थलेऽपि विहितत्वसंबन्धेनान्वय इत्याशयेन शङ्कते—इह तर्हीति ॥ वैषम्यमुपपादयन्स्वाशयमाह—इह तावादित्यादिना—इति भाष्यार्थमाहुः ॥

(समाधानबाधकभाष्यम्)

इह तर्हि-प्रियसक्थ्ना ब्राह्मणेन । अनङ् न प्राप्नोति ॥

(प्रदीपः) प्रियसक्थ्नेति । सक्थिशब्दः शकटावयववचनोऽत्रेति 'बहुव्रीहौ सक्थ्यक्ष्णोः-' इति समासान्तो न कृतः ॥

(उद्द्योतः) शकटेति । स च न स्वाङ्गमिति भावः ॥

(समाधानसाधकभाष्यम्)

सप्तमीनिर्दिष्टे यदुच्यते, प्रकृतविभक्तौ तद्भवति ॥

(प्रदीपः) प्रकृतविभक्ताविति । अङ्गार्थसंबन्धिन्यां विभक्तावित्यर्थः ॥

(उद्द्योतः) अङ्गार्थेति । प्रकृतशब्देनाङ्गम् ॥

(समाधानबाधकभाष्यम्)

यद्येवम्, अतितत्-अतितदौ-अतितदः-इति अत्वं प्राप्नोति ॥

तत्रापि वक्तव्यम् ॥

(प्रदीपः) तत्रापीति । 'गृह्यमाणविभक्तेः' इति 'सप्तमीनिर्दिष्टे यदुच्यते' इति च ॥

(उद्द्योतः) 'एतत्रापि' इति वक्तव्ये तच्छब्दनिर्देशाद्व्यवहितपरामर्शः, अपिनाऽव्यवहितस्य चेत्याह—गृह्यमाणेत्यादि ॥

(पक्षान्तरेण समाधानभाष्यम्)

न वक्तव्यम् । इह तावत्-"अड्डतरादिभ्यः पञ्चभ्यः" इति पञ्चमी, 'अङ्गस्य' इति षष्ठी, समानाश्रयं विविभक्तित्वात् 'डतरादिभ्यः' इति पञ्चम्याऽङ्गं विशेषयितुम् । तत्र किमन्यच्छक्यं विशेषयितुमन्यदतो विहितात्प्रत्ययात्—डतरादिभ्यो यो विहित इति ॥

(प्रदीपः) डतरादिभ्यो यो विहित इति । अर्थद्वारकं विधानमाश्रयितव्यम् । तेन परमकतरत्-इत्यत्रापि भवति । 'युष्मदस्मद्भ्यां ङसोऽश्' इत्यत्र तु प्रकरणेऽङ्गेन विभक्तिर्विशेष्यतेऽर्थद्वारेण, युष्मदस्मद्भ्यां तु परत्वमात्रेणेति-अतियुष्मदित्यादावपि कार्यं भवति ॥

(उद्द्योतः) अर्थद्वारकमिति । डतरादिभ्यो विहितो योऽर्थस्तत्प्रतिपादकत्वमोरित्यर्थः ॥ तदर्थकप्रत्ययविधानेऽर्थस्यापि विधानमस्तीत्यभिमानः ॥ डतरादिभ्य इत्यस्य षष्ठ्यर्थत्वे तु विविभक्तित्वादिति भाष्यविरोधः ॥

परे तु विधानस्य सर्वथाऽनाश्रयणेन 'अर्थद्वारकं विधानमाश्रयितव्यम्' इति ग्रन्थविरोधः, तस्माद्विहितविशेषणमिति यथाश्रुतमेव भाष्यम् । परमकतरदित्यत्राड्डादेशे न भाष्यान्तरं मानमस्ति । प्रकृतभाष्यं तु विपरीतं तदभावबोधकमेवेति प्रामाणिकाः ॥ 'त्यदादिप्रकृतिकविभक्तौ' इत्यर्थं मत्वा शङ्कते—यद्येवं-इति ॥ उक्ताशयेनाह—त्यदादिप्रधान-इति । अङ्गस्येति सूत्रेऽतो भिस ऐसित्यादौ विविभक्तित्वादसंबन्धमाशङ्क्याङ्गनिमित्तं यो भिसिति संबन्धं वक्ष्यति । तेन न्यायेनात्रापि संबन्धसंभवादियमेकदेश्युक्तिः । तस्माल्लक्ष्यानुसारात् षड्भ्यो-डतरादिभ्य इति सूत्रद्वये विहितविशेषणं भाष्यसंमतम्, तस्यार्थस्य लक्ष्यविरोधेन भाष्यकृता दूषणाकरणादित्याहुः ॥

(पक्षान्तरेण समाधानभाष्यपरिशिष्टम्)

इहेदानीम्—"अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः" इति, त्यदादीनामो भवतीति ।

अस्थ्यादीनामित्येषा षष्ठी, 'अङ्गस्य' इत्यपि । 'त्यदादीनाम्' इत्यपि षष्ठी, 'अङ्गस्य' इत्यपि । तत्र कामचारः-गृह्यमाणेन विभक्तिं विशेषयितुम्-अङ्गेन वा । यावता कामचारः ।

इह तावत्-"अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः"-इति । अङ्गेन विभक्तिं विशेषयिष्यामः, अस्थ्यादिभिरनङम्—अङ्गस्य विभक्तावनङ् भवति अस्थ्यादीनामिति ॥

इहेदानीं—त्यदादीनामो भवतीति । गृह्यमाणेन विभक्तिं विशेषयिष्यामः, अङ्गेनाकारम्-त्यदादीनां विभक्तावो भवति अङ्गस्येति ॥

(उद्द्योतः) भाष्ये-अकारविषयेऽपि समाधानं वक्तुमाह—इहेति ॥ इह तावदिति । लक्ष्यानुसारश्च तत्र तत्र तथा तथा व्याख्याने बीजम् । अङ्गस्य विभक्तावित्यादिश्चाङ्गार्थगतार्थप्रतिपादकविभक्तावित्याद्यर्थः । षष्ठ्यन्तत्वेन तथाऽन्वयस्य सूपपादत्वादिति भावः ॥

(समाधानाक्षेपपरिहारभाष्यम्)

यद्येवम्, 'अतिसः' अत्वं न प्राप्नोति ॥

नैष दोषः, त्यदादिप्रधान एष समासः ॥

(प्रदीपः) **अतिस इति** । शोभनः सः-इति प्रादिसमासः । नञ्समासेऽपि असः-अषट्-अकतरत्-इति भवति ॥

(उद्द्योतः) नञ्समासेऽपीति । उत्तरपदार्थप्रधानत्वादिति भावः । 'अतिकतरत्' इति उक्तरीत्या चिन्त्यमेव । अत्रापि पक्षेऽतिसर्वायेत्यादौ दोष एव, परमसर्वत इत्यादिसिद्धये तदन्तस्यापि सर्वनामत्वावश्यकत्वेन सर्वनाम्नो विहितस्य ङेः स्मै-इत्यर्थेऽपि स्मैभावस्य दुर्वारत्वात् । अतोऽप्येकदेश्युक्तिरिदं पक्षद्वयम् ॥

(सिद्धान्तिभाष्यम्)

अथवा—नेदं संज्ञाकरणम्, पाठविशेषणमिदम् । सर्वेषां यानि नामानि तानि सर्वादीनि । संज्ञोपसर्जने च विशेषेऽवतिष्ठेते ॥

(प्रदीपः) **सर्वेषां यानीति** । स्वविषयापेक्षया सर्वनामत्वं बोद्धव्यम् । यथा-गोत्वादेः स्वविषयापेक्षं सर्वगतत्वम्, न तु एतानि सर्वार्थानि परस्परं पर्यायतां यान्ति, भिन्नार्थत्वात् ॥

(उद्द्योतः) अतः सर्वसाधारणं समाधिमाह—भाष्ये-अथवा नेदमिति । द्वन्द्वे चेत्यादिभिश्च सर्वादिस्वस्यैव निषेधस्तत्प्रयुक्तकार्याभावे पर्यवस्यति । एवं विकल्पोऽपीत्यभिमानः ॥ ननु सर्वार्थवाचकत्वं न पूर्वादिशब्दानामित्यसङ्गतमेतदत आह—स्वविषयेति । लोकनिरूढप्रवृत्तिनिमित्तेन या अभिधेया व्यक्तयस्ताः—स्वविषयः ॥ ननु सर्वादिगणपठितानां शब्दानां सर्वेषां सर्वार्थकत्वेन पर्यायत्वापत्त्याऽयं व्याख्यानक्लेशोऽत आह—नत्विति ॥ नन्वेवं घटादिशब्दानामपि स्वविषयापेक्षसर्वनामत्वाद् घटायेत्यादौ स्मैभावापत्तिरिति चेत् । न, तद्विधायकेषु सर्वनामग्रहणसामर्थ्येन सकृद्गृहीतशक्त्यैव स्वप्रवृत्तिनिमित्ताश्रयविरुद्धानेकजातीयार्थबोधकानामेव सर्वनामपदेन ग्रहणात् । एतदेव ध्वनयितुं सर्वेषां नामानीति बहुवचनान्तपूर्वपदको विग्रहो दर्शितो भाष्ये ॥ भाष्ये—संज्ञोपसर्जने चेति । संज्ञा त्वेकद्रव्यनिष्ठत्वान्न सर्वेषां नाम । उपसर्जनमपि पदान्तरार्थसंसृष्टार्थवृत्तित्वान्न प्राधान्येन सर्वेषामुपस्थापकम्, नामपदस्वारस्येन तथैव लाभादित्यर्थः ॥ उपसर्जनांशे 'विशेषे' इत्यस्य 'विशेषणे' इत्यर्थः ॥

(समाधानबाधकभाष्यम्)

यद्येवम्, संज्ञाश्रयं यत्कार्यं तन्न सिध्यति—"सर्वनाम्नः स्मै" "आमि सर्वनाम्नः सुट्" इति ॥

(समाधानसाधकभाष्यम्)

अन्वर्थग्रहणं तत्र विज्ञास्यते । सर्वेषां यन्नाम तत्सर्वनाम । सर्वनाम्न उत्तरस्य ङेः स्मै भवति । सर्वनाम्न उत्तरस्यामः सुट् भवति ॥

(समाधानबाधकभाष्यम्)

यद्येवम्, सकलं कृत्स्नं जगत्-इत्यत्रापि प्राप्नोति ॥ एतेषां चापि शब्दानामेकैकस्य स स विषयः, तस्मिन् तस्मिन् विषये यो यः शब्दो वर्तते तस्य तस्य तस्मिंस्तस्मिन्वर्तमानस्य सर्वनामकार्यं प्राप्नोति ॥

(प्रदीपः) **एतेषां चापीति** । ततश्च 'सर्वस्मिन्नोदने' इत्योदनशब्दस्यापि सर्वनामकार्यं प्राप्नोति, सामानाधिकरण्यादनयोः ॥ ननु प्रतिनियतवस्तुभागाभिनिवेशित्वाच्छब्दानां सर्वत्वमोदनशब्देन नाभिहितम्, ओदनत्वमपि सर्वशब्देनेति कुतोऽयं प्रसङ्गः ॥ तत्रेदं दर्शनम्—सर्वशब्द ओदनार्थावग्रहेण प्रवृत्तः, ओदनशब्दोऽपि सर्वशब्दार्थावग्रहेण । प्रतिपत्ता तु केवलात्सर्वशब्दाद्विशेषं न प्रतिपद्यते, रूपसादृश्यात्; नाप्योदनशब्दात्-इति तत्प्रतिपत्त्यर्थमुभयोरुपादानम् । तत्रैकस्य सर्वनामकार्यं भवति नापरस्य-इति प्रमाणाभावादतिप्रसङ्ग उद्भावितः ॥

(उद्द्योतः) भाष्ये-एतेषां चापीति-दूषणान्तरम् । **एतेषां चापि**=घटादिशब्दानामपि ॥ **एकैकस्य**=तस्यापि ॥ **स स विषयः**—सर्वाद्यर्थो विषयः ॥ **तस्मिंस्तस्मिन्विषये**=सर्वाद्यर्थरूपे विषये ॥ **यो यः शब्दो** घटादिशब्दो **वर्तते तस्य तस्य** घटादिशब्दस्य सर्वाद्यर्थे वर्तमानस्येत्यक्षरार्थः, तद्व्याचष्टे—ततश्चेति । पदैः पदार्थानभिधायाकाङ्क्षादिमूलकशक्तिवशात्संसृष्टवाक्यार्थप्रतीतिर्जन्यत इत्यभिहितान्वयवादे शङ्कते—नन्विति । गुणद्रव्यादिसमुदायात्मके वस्तुनि प्रतिनियता ये भागाः-प्रवृत्तिनिमित्ताख्यास्तदभिनिवेशित्वात् तद्वाचकत्वाच्छब्दानामित्यर्थः ॥ योग्येतरान्वितपदानां शक्तेः स्वार्थवत्पदान्तरार्थोऽपि स्ववाच्य इत्यन्विताभिधानमाश्रित्य परिहरति—तत्रेति ॥ अवग्रहः=क्रोडीकारः ॥ **न प्रतिपद्यते**—निश्चिततयेति शेषः ॥ **रूपसादृश्यादिति** । ओदनव्यतिरिक्तार्थान्वययोग्यसर्वशब्दरूपस्य तुल्यत्वादित्यर्थः ॥ **तत्प्रतिपत्त्यर्थम्**—निर्धारितविशेषप्रतिपत्त्यर्थम् ॥

अपरे तु—पदे पदैकदेशप्रयोगवत् यदा 'सर्वस्मिन्नोदने' इति वाक्ये प्रयोक्तव्ये 'ओदने' इति वाक्यैकदेशः प्रयुज्यते, प्रकरणाच्च तत एव पदात्तादृशवाक्यार्थबोधस्तत्र दोष इति भाष्याशयः ॥ यथा च पदशक्तिग्रहकाले पदैकदेशस्यापि तत्र शक्तिग्रह इति पस्पशायां कैयटेनोक्तम्, तथा वैयाकरणमते विशेषणविशेष्यभावे वाक्यस्य शक्त्यङ्गीकारेण तत्र तत्तत्पदार्थालिङ्गिते समुदितस्य शक्तिग्रहकालेऽवयवभूतैकैकपदस्यापि तत्र शक्तिग्रहेणैकैकपदादपि तादृशविशिष्टार्थबोध इति द्व्यण इतिसूत्रे भाष्ये ध्वनितम् ॥ आकाङ्क्षावादान्ते च मञ्जूषायां निरूपितमित्याहुः ॥

अतिप्रसङ्ग उद्भावित इति । न च 'सर्वनाम्नः स्मै' इत्यादौ 'सर्वादेः स्मै' इत्याद्येव सूत्राणि सन्त्विति न कृत्स्नादिषु दोषः । अपाणिनीयत्वापत्तेः ॥

(समाधानसाधकभाष्यम्)

एवं तर्हि उभयमनेन क्रियते—पाठश्चैव विशेष्यते, संज्ञा च ॥

(उद्द्योतः) भाष्ये-एवं तर्ह्युभयमिति ॥

(आक्षेपभाष्यम्)

कथं पुनरेकेन यत्नेनोभयं लभ्यम् ?

(समाधानभाष्यम्)

लघ्यमित्याह ।

एकशेषनिर्देशात् ।

एकशेषनिर्देशोऽयम्-सर्वादीनि च सर्वादीनि च-सर्वादीनि । सर्वनामानि च सर्वनामानि च-सर्वनामानि । सर्वादीनि सर्वनामसंज्ञानि भवन्ति, सर्वेषां यानि च नामानि तानि सर्वादीनि । संज्ञोपसर्जने च विशेषेऽवतिष्ठेते ॥

(प्रदीपः) एकशेषनिर्देश इति । ननु सहविवक्षाया अभावात् कथमेकशेषः । एकशेषफलत्वात्तन्त्रन्यायः-आवृत्तिर्वैकशेषशब्देनोच्यते । अथवा—आकृत्यभिधानपक्षे एकस्यैव प्रयोगे सिद्धे प्रत्याख्यातमेकशेषशास्त्रं संज्ञापरिभाषावच्छास्त्रप्रक्रियासंपादनार्थं भवतीति सहविवक्षामन्तरेणापि भवत्येकशेषः ॥ संज्ञोपसर्जने चेति । यदा सर्वशब्दः संज्ञात्वेन विनियुज्यते, तदा प्रसिद्धप्रवृत्तिनिमित्तपरित्यागेन स्वरूपमात्रोपकारी प्रवर्तते इति विशेष एवावतिष्ठते । उपसर्जनमपि जहत्स्वार्थमजहद्वाऽतिक्रान्तार्थविशेषणतामापन्नमतिक्रान्तार्थवृत्ति भवति 'अतिसर्वाय' इत्यत्र ॥ वाक्ये त्वसंसृष्टार्थत्वात् स्वार्थमात्रं प्रतिपादयतो न विशेषेऽवस्थानम् ॥

(उद्द्योतः) सहेति । एकैकस्योद्देश्यत्वविधेयत्वसत्त्वात्सहविवक्षाऽभाव इत्यर्थः ॥ अर्थद्वयबोधेच्छया एकस्य सकृदुच्चारणमिह तन्त्रम् । अत्रोच्चारणं तन्त्रेण, बोद्धृबोधस्तु पुनरनुसन्धानेनेत्याशयेनाह—आवृत्तिर्वेति । आवृत्तिश्चेत्यर्थः ॥ प्रत्याख्यातमिति । लौकिकप्रयोगाङ्गत्वेन निराकृतमित्यर्थः ॥ प्रसिद्धप्रवृत्तिनिमित्तेति । तच्च सर्वशब्दस्य यावत्त्वम् । इदमुपलक्षणम्—अनेकार्थसाधारणशक्तिग्रहसहकारेण स्वविषयाणां सर्वेषामर्थानां प्राधान्येन बोधकत्वं सर्वनामत्वमित्यस्यार्थस्य ॥ स्वरूपमात्रोपकारीति । स्वरूपमात्रप्रवृत्तिनिमित्तक इत्यर्थः ॥ अतिक्रान्तार्थविशेषणतामिति । एवं च प्राधान्येन न सर्वार्थोपस्थापकत्वमिति भावः ॥ जहत्स्वार्थत्वे तु सर्वोपस्थापकत्वमेव नेति बोध्यम् ॥

(समाधानान्तरभाष्यम्)

अथवा—महतीयं संज्ञा क्रियते । संज्ञा च नाम यतो न लघीयः ।

कुत एतत् ?

लघ्वर्थं हि संज्ञाकरणम् । तत्र महत्याः संज्ञायाः करणे एतत्प्रयोजनम्—अन्वर्थसंज्ञा यथा विज्ञायेत । सर्वादीनि सर्वनामसंज्ञानि भवन्ति । सर्वेषां नामानीति चातः सर्वनामानि-इति । संज्ञोपसर्जने च विशेषेऽवतिष्ठेते ॥

(प्रदीपः) यतो न लघीय इति । शब्दव्यवहारो लघुः, ततोऽपि लघीयो नाम । तत्र गुरुसंज्ञाकरणात्सर्वादीनां विशिष्टो धर्मोऽनुमीयते—नूनमेतानि संज्ञाप्रवृत्तिनिमित्तेन सर्वनामत्वेन युक्तानि । यतस्तदनुरूपा तेषां संज्ञा कृतेति सर्वनामकार्यमन्तर्गणकार्यं च सर्वनामत्वयुक्तानामेव भवति, न संज्ञोपसर्जनानाम् ॥

(उद्द्योतः) भाष्ये—अथवा महतीति । अयं भावः—अनेकार्थसाधारणशक्तिग्रहसहकारतः प्राधान्येन स्वविषयसर्वार्थोपस्थितिजनकत्वसमानाधिकरणसर्वनामपदवत्त्वेन बोधकमहासंज्ञया तादृशसर्वादीनामेव गणेऽनुकरणम् । तत्र संज्ञायास्तत्त्वाभावः स्पष्ट एव । उपसर्जनस्यापि न प्राधान्येन तदुपस्थापकत्वं, नामपदस्वारस्येन तथैव लाभात् । उपसर्जनं हि-इतरविशेषणतयैव स्वार्थोपस्थापकम् । सर्वादीनि तदन्तानि च सर्वार्थवाचकत्वसमानाधिकरणसर्वनामपदवन्तीत्यर्थः सूत्रस्य । तदन्ते च तत्प्रधानसमासेऽवयवीयतादृशशक्तिग्रहसहकारेण स्वविषयसर्वबोधकत्वं विशेष्यतयाऽस्त्येवेति दिक् ॥ ततोऽपि लघीयो नामेति । संज्ञेत्यर्थः । तन्नाम संज्ञा यतोऽन्यत् लघुतरं नास्तीत्यन्वयो भाष्ये । यद्वा संज्ञा च नामेति पर्यायप्रदर्शनम् । तच्च यतो नान्यल्लघीयस्तत् । एवं च संज्ञायां सर्वतः शब्दव्यवहाराल्लघीयस्त्वं सिद्धम् ॥ लघ्वर्थमित्यस्य लाघवेन शास्त्रप्रवृत्त्यर्थमित्यर्थः ॥ नन्वन्वर्थसंज्ञात्वं नाम योगरूढत्वम् । तत्र योगार्थस्य रूढ्यर्थेनैवान्वयनियमात् पृथगुद्देश्येनानन्वयात् कथं सर्वार्थवाचकानामेव संज्ञेत्यत आह—अनुमीयत इति ॥ नूनमेतानीति । गणपठितानीत्यर्थः ॥

(उभशब्दपाठप्रयोजनाधिकरणम्)

(आक्षेपभाष्यम्)

अथोभस्य सर्वनामत्वे कोऽर्थः ?

(उद्द्योतः) भाष्ये—अथोभस्येति । उभयत इत्यादेरुभयशब्दपाठेनैव सिद्धेरिति भावः ॥

(१९८ समाधानवार्तिकम् ॥ १२ ॥)

॥ * ॥ उभस्य सर्वनामत्वेऽकजर्थः ॥ * ॥

(भाष्यम्)

उभस्य सर्वनामत्वेऽकजर्थः पाठः क्रियते । उभकौ ॥

(आक्षेपभाष्यम्)

किमुच्यतेऽकजर्थ इति, न पुनरन्यान्यपि सर्वनामकार्याणि ?

(१९९ समाधानहेतुवार्तिकम् ॥ १३ ॥)

॥ * ॥ अन्याभावो द्विवचनटाब्विषयत्वात् ॥ * ॥

(भाष्यम्)

अन्येषां सर्वनामकार्याणामभावः ।

किं कारणम् ?

'द्विवचनटाब्विषयत्वात् ।' उभशब्दोऽयं द्विवचनटाब्विषयः । अन्यानि च सर्वनामकार्याणि एकवचनबहुवचनेषूच्यन्ते ॥

(प्रदीपः) **अन्याभाव इति** । टाब्विषयत्वमपि न द्विवचनादन्यत्र बोद्धव्यम् । तत्र 'उभादुदात्तो नित्यम्' इत्यत्र नित्यग्रहणस्येदं प्रयोजनम्—वृत्तिविषये उभशब्दस्य प्रयोगो मा भूत्, उभयशब्दस्यैव यथा स्यादिति–उभयपुत्र इत्यादि भवति ॥ द्विदण्ड्यादिभ्यश्चेत्यत्र निपातनात् 'उभाबाहु' इत्यादयः साधवः ॥

(उद्द्योतः) ननु टावन्ते सर्वनाम्नः स्याड्डित्याद्यन्यसर्वनामकार्यसंभवोऽस्त्येवेत्यत आह—**टाब्विषयत्वमपीति** । 'अन्याभावः' इत्यत्र हेतुत्वेनोपादानादिति भावः ॥ एवं चोभशब्दः केवलद्विवचनविषयष्टाप्सहितद्विवचनविषयो वेत्यर्थः–इति टाब्ग्रहणमनुवादमात्रं नापूर्वमिति तात्पर्यम् ॥ द्विवचनटाब्विषयत्वे उपपत्तिमाह—**तत्रेति** । द्वित्रिभ्यामिति सूत्रस्य 'वा'इत्यस्यास्वरितत्वादेवाननुवृत्तौ तयप्स्थानिकत्वेनायचः-तद्विकल्पेनैव वाक्यसिद्धौ फलाभावेन महाविभाषाया अप्यसंबन्धसिद्धौ प्रत्ययान्तरत्वपक्षे तन्निवृत्तौ दोषाच्च नित्यग्रहणं योगविभागेन स्वार्थिकानादेशभूतायच्प्रत्ययान्तरविधायकमिति भावः ॥ अत्र च नित्यशब्दस्य वाच्यार्थविरोधाद्विकल्पाननुवृत्तिः । अयमप्याद्युदात्त एव, प्रत्ययैसंबन्धोदात्तग्रहणानुवृत्तेः ॥ **वृत्तिविषये इति** । अत एवोभौ साभ्यासस्येति निर्देशः सङ्गच्छते । इदं च सूत्रं योगविभागस्येष्टसिद्ध्यर्थत्वाद् उभाविति निर्देशाच्च उभयोऽन्यत्रेति वार्तिकाच्च द्विवचनाश्रवणं यत्र तत्रैव प्रवर्तते, नान्यत्र । तेन नातिप्रसङ्गः ॥ **द्विवचनविषयत्वादिति** भाष्यस्य द्विवचनसत्त्वे एवोभशब्दः साधुरित्यर्थः ॥ द्विवचनासत्ता च वृत्तिविषय एवेत्याशयेन कैयटे वृत्तिविषये इत्युक्तम् ॥

(आक्षेपभाष्यम्)

यदा पुनरुभशब्दो द्विवचनटाब्विषयः, क इदानीमस्यान्यत्र भवति ?

(उद्द्योतः) **क इदानीमिति** । अस्योभशब्दस्यार्थप्रतिपादकः कः-शब्दोऽन्यत्र-तसिलादिविषये द्विवचनाभावे भवतीत्यर्थः ॥

(२०० समाधानवार्तिकम् ॥ १४ ॥)

॥ * ॥ उ॒भयोऽन्यत्रेति ॥ * ॥

(भाष्यम्)

उभयशब्दोऽस्यान्यत्र भवति । उभये देवमनुष्याः, उभयो मणिरिति ॥

(उद्द्योतः) **उभयोऽन्यत्रेति** । द्विवचनविषयत्वाभावसंभावनायामिति भावः ॥ लुग्विषये लुका विषयस्यैवापहारान्न दोषः । संभावनानिवेशाच्चोभयस्य पाठाभावेऽप्युभयत इत्यादिसिद्धिः । अन्यथोभात्तसिलादेः कर्तुमशक्यतया द्विवचनस्य लुगभावेन तद्विषयस्यैव सत्त्वेनायजनापत्तौ 'उभयतः' इत्याद्यसिद्धिः ॥ मम तु यद्यत्र तसिलादि स्यात् तर्हि लुगपि स्यादिति संभावनया विषयाभावसंभावनाऽस्त्येवेति न दोषः । इदमेव ध्वनयितुं विषयपदमुपात्तम् ॥

उभयेति । वार्तिके उभयशब्देन स्वार्थिकायजन्तस्यावयव्यर्थकायजन्तस्य च ग्रहणमिति भावः ॥

(आक्षेपभाष्यम्)

किंच स्यात्, यद्यत्राकज् न स्यात् ?

(समाधानभाष्यम्)

कः प्रसज्येत ॥

(आक्षेपभाष्यम्)

कश्चेदानीं काकचोर्विशेषः ?

(प्रदीपः) **कश्चेदानीमिति** । रूपे स्वरे च नास्ति विशेषः । अवग्रहे च नास्त्यादरः, न हि लक्षणेन पदकारा अनुवर्त्याः । [उभकाभ्यां हेतुभ्यां उभकयोर्हेत्वोरिति षष्ठीतृतीये सिद्धे, निमित्तकारणहेतुषु सर्वासां प्रायदर्शनमिति वचनात् ॥]

(उद्द्योतः) **रूपे इति** । नन्वकचि उभशब्देन तद्विशिष्टस्य ग्रहणादुभकाववयवौ यस्येत्यर्थे उभकयो मणिरिति प्रयोगः सिध्यति, के तु नेति फले विशेषः स्पष्टः । एवमज्ञातोभयोर्घट इत्यर्थेऽकचि उभकघट इति रूपम् । केऽयचि उभयक इति स्यादिति रूपे विशेषः स्पष्ट एवेति चेन्न । भाष्यप्रामाण्येनानभिधानात् । अत एव हरिणा उभयोन्यत्रेति वार्तिकमूलभूतं "उभयस्य द्विवचनं टाप्च लोपश्च यस्य"इति व्याकरणान्तरसूत्रमुदाहृतम् । तन्मते ह्येषां प्रयोगाणामभावः स्पष्ट एवेति बोध्यम् ॥ **स्वरे चेति** । चित्स्वरप्रत्ययस्वराभ्यामुभयत्रापि अन्तोदात्तत्वस्यैव सिद्धेरिति भावः ॥ उभकाभ्यामित्यादिर्वचनादित्यन्तो ग्रन्थः प्रक्षिप्तः, पुनरग्रे दर्शनात् ॥

(समाधानभाष्यम्)

"उभशब्दोऽयं द्विवचनटाब्विषयः" इत्युक्तम् । तत्राकचि सति अकचस्तन्मध्यपतितत्वाच्छक्यते एतद्वक्तुं—द्विवचनपरोऽयमिति । के पुनः सति नायं द्विवचनपरः स्यात् । तत्र द्विवचनपरता वक्तव्या ॥

(प्रदीपः) **उभशब्दोऽयमिति** । द्विवचनेऽनन्तरे श्रूयमाणे उभशब्देन साधुना भाव्यं, न लुप्ते, न व्यवहिते ॥ **के पुनः सतीति** । पूर्वस्य द्विवचनस्य लुप्तत्वादपरस्य केन व्यवधानात् । तत्र-कविषये व्यवहितद्विवचनविषय उभशब्दः साधुर्भवतीति वक्तव्यम् ॥

(उद्द्योतः) **श्रूयमाण इति** । विषयशब्दलभ्योऽयमर्थः । श्रूयमाणत्वं न साक्षाद्-भावरूपादेशद्वारा वा-इत्यन्यत् ॥ **व्यवधानादिति** । द्विवचनविषयत्वस्याव्यवहितस्यैव निवेशादित्यर्थः ॥ उभयघटावित्यादौ व्यवहितद्विवचनपरस्य साधुत्ववारणाय—कविषये इति । एव चैतद्वचनाकरणलाघवार्थमुभशब्दपाठ इति भावः ॥

(आक्षेपभाष्यम्)

यथैव तर्हि के सति नायं द्विवचनपरः, एवमाप्यपि सति नायं द्विवचनपरः स्यात् । तत्र द्विवचनपरता वक्तव्या ॥

(प्रदीपः) **यथैव तर्हीति** । ननु 'द्विवचनटाब्विषयत्वात्' इत्यत्र टाप उपात्तत्वाच्चोद्यानुपपत्तिः । एवं तर्हि टाब्विषयत्वमेकवचनबहुवचनयोर्मा भूदित्येवमर्थमाप्यपि द्विवचनपरता वक्तव्येत्युक्तम् ॥

(उद्द्योतः) भाष्ये—**एवमाप्यपीति** । टापा व्यवधानादिति भावः ॥

(समाधाने वार्तिकांशानुवादः ॥)

अवचनाद्वापि तत्परविज्ञानम् ॥

(भाष्यम्)

अन्तरेणापि वचनमपि द्विवचनपरोऽयं भविष्यति ॥

(प्रदीपः) **अवचनादिति** । स्वार्थिकत्वादाप उभार्थस्याज्ञानादापि सिद्धा द्विवचनपरतेत्यर्थः

(उद्द्योतः) (भाष्ये)—अन्तरेणापीति । दीर्घे तद्विशिष्टस्यान्तवद्भावेनोभशब्दत्वमिति भावः ॥ आवन्तादेकवचनाचापत्तिरतु नेत्याह—**स्वार्थिकत्वादिति** । एवं च तत एकवचनादौ द्विवचनविषयत्वं कथमिति न वक्तव्यमिति भावः ॥

(आक्षेपभाष्यम्)

[किं वक्तव्यमेतत् ?

(समाधानभाष्यम्)

नहि ॥

(आक्षेपभाष्यम्)

कथमनुच्यमानं गंस्यते ?

(समाधानभाष्यम्)

एकादेशे कृते द्विवचनपरोऽयमन्तादिवद्भावेन ॥]

(उद्द्योतः) **किं वक्तव्यमेतदित्यादिरन्तादिवद्भावेनेत्यन्तोऽपाठः** । अवचनादापीत्यस्य वक्तव्यत्वाभावेन किं वक्तव्यमिति प्रश्नासङ्गतेः ॥ तथा भ्रममूलको वा प्रश्न इति बोध्यम् ॥

(प्रत्याख्याने भाष्यवार्तिकम्)

अवचनादापि तत्परविज्ञानमिति चेत्केऽपि तुल्यम् ॥

(भाष्यम्)

अवचनादापि तत्परविज्ञानमिति चेत्केऽपि अन्तरेण वचनं द्विवचनपरो भविष्यति ।

कथम् ?

'स्वार्थिकाः प्रत्ययाः प्रकृतितोऽविशिष्टा भवन्ति' इति प्रकृतिग्रहणेन स्वार्थिकानामपि ग्रहणं भवति ॥

(प्रदीपः) **केऽपि तुल्यमिति** । 'द्विवचनविषयत्वात्' इत्यत्र द्विवचनशब्देन प्रत्ययो न गृह्यते । किं तर्हि? द्व्यर्थाभिधानसमर्थ इत्यर्थः ॥ 'उभयतः' 'उभयत्र' इति त्रतसोरव्ययत्वात् द्वित्वाभिधानसामर्थ्यं नास्तीत्यभेदविषय उभयशब्द एव प्रयुज्यते, न तूभशब्दः ॥ एवं प्रत्याख्यातोऽकजर्थं उभशब्दस्य पाठः ॥ 'सर्वनाम्नस्तृतीया च' इति षष्ठीतृतीयार्थः पाठ इति केचित् । 'निमित्तकारणहेतुषु सर्वासां प्रायदर्शनम्' इति वचनात्तदर्थोऽपि पाठो न कर्तव्य इत्यन्ये ॥

(उद्द्योतः) **व्यर्थेति** । कृत्रिमाकृत्रिमन्यायस्य तु नेह प्रवृत्तिः, तस्या इह शास्त्रेऽनाश्रयणस्य संख्यासंज्ञासूत्रे भाष्ये उक्तेः । अस्य लोकसिद्धव्यवस्थाबोधकत्वेन तत्र न्यायाप्रवृत्तेश्चेति भावः ॥ ननूभकावितिवद् 'उभतः' इत्याद्यपि प्रसज्येतेत्यत आह—**उभयत इत्यादि** । तयोरव्ययत्वेन विभक्त्यन्तीयस्वार्थिकत्वेन चाधिकरणापादानशक्तिविशेष्यकबोधजनकत्वाद् ॥ **द्विवचनत्वं च** संख्याप्रकारकसंख्येयविशेष्यकबोधजनकत्वम् ॥ **अभेदविषयः—** द्वित्वविषयः ॥ उक्तमर्थं प्रश्नपूर्वं व्युत्पादयति—भाष्ये-**कथम् ? स्वार्थिका इति** । यतः स्वार्थिकाः प्रकृतितोऽविशिष्टाः—अन्यार्थविशेष्यकबोधाजनका अतः प्रकृतिर्गृह्यते अनेनेति-प्रकृतिग्रहणं, तेन—प्रकृतिभूतोभशब्दग्राहकेण द्विवचनशब्देन तत्प्रकृतिकानां स्वार्थिकानां कादीनामपि ग्रहणमित्यर्थः । तेनोभयत इत्यादेर्व्यावृत्तिः । **प्रकृतिग्रहणेनेत्यनेन** कृत्रिमाकृत्रिमन्यायाप्रवृत्तिर्ध्वनिता । द्विवचनं च टाप्साहचर्यात्प्रत्यय एव गृह्यते । एतदर्थमेव टापग्रहणम् । तेनोभयोरुभावित्यत्र समासे भवत्येवायच्-इत्याहुः ॥ **एवं प्रत्याख्यात इति** । किं च अकज्मात्रार्थत्वे उभाव्ययसर्वनाम्नामकच्चित्येव पाठेन सिद्धे संज्ञाप्रयोजको गणे पाठो व्यर्थः । साहचर्याच्च संज्ञादिव्यावृत्तिरिति बोध्यम् ॥

(भवच्छब्दपाठप्रयोजनाधिकरणम्)

(आक्षेपभाष्यम्)

अथ भवतः सर्वनामत्वे कानि प्रयोजनानि ?

(प्रदीपः) **अथ भवत इति** । अनकारान्तत्वात् स्मायाद्यभावात्प्रश्नः ॥

(समाधानभाष्यम्)

भवतोऽकच्छेषात्वानि प्रयोजनानि ॥

अकच्—भवकान् ॥

शेषः—स च भवांश्च-भवन्तौ ॥

आत्वम्—भवादृगिति ॥

(प्रदीपः) **शेष इति** । पाठे सति त्यदादित्वाच्छेषो भवति॥

(आक्षेपभाष्यम्)

किं पुनरिदं परिगणनम्, आहो स्विदुदाहरणमात्रम् ?

(समाधानभाष्यम्)

उदाहरणमात्रमित्याह । तृतीयादयोऽपि दृश्यन्ते । "सर्वनाम्नस्तृतीया च"-भवता हेतुना, भवतो हेतोरिति ॥ २७ ॥

(प्रदीपः) **तृतीयादयोऽपीति** । 'निमित्तकारणहेतुषु सर्वासां प्रायदर्शनम्' इत्यनपेक्ष्यैतदुक्तम् ॥ इदं तु प्रयोजनम्—भावतायनिः, भवद्यच्, भवन्मयः । पूर्वनिपातश्च—भवन्मित्रः । 'भवतष्ठक्छसौ' इति वृद्धत्वात् ठक्छसौ, गुणवचनसंज्ञाबाधनं च, भवतो भावः–भावत्यमिति मा भूत् ॥ २७ ॥

(उद्द्योतः) **इदं त्विति** । भाष्ये आदिपदसंग्राह्यमित्यर्थः ॥ **भावतायनिरिति** । सति पाठे त्यदादीनि चेति वृद्धत्वे उदीचां वृद्धादिति फिञ् ॥ **भवद्यजिति** । पितृव्यमातुलेत्यत्र भवतश्च इति चेन सर्वनाम्नोऽनुकर्षणाद्यजादेशः ॥ भवन्मये **नित्यं वृद्धेति** मयट् ॥ भवन्मित्रे **बहुव्रीहौ सर्वनामसंख्ययो**रिति पूर्वनिपातः ॥ भवत-

इतिति । शब्रन्तनिवृत्तये वृद्धग्रहणं तत्रानुवर्तत इत्यर्थः ॥ गुणवचनेति । एकसंज्ञाधिकारे सकलप्रातिपदिकविषयगुणवचनसंज्ञातः परा सर्वनामसंज्ञेति भावः ॥ २७ ॥

(२६ सर्वनामसंज्ञासूत्रम् ॥ १ । १ । ६ आ. २ ॥)

विभाषा दिक्समासे बहुव्रीहौ ॥ १ । १ । २८ ॥

(तत्तत्पदप्रयोजनाधिकरणम्)

(आक्षेपभाष्यम्)

दिक्ग्रहणं किमर्थम् ?

(प्रदीपः) **विभाषा दिक्समासे० ॥ २८ ॥ दिक्ग्रहणमिति** । एकस्मिन्विषये विकल्पप्रतिषेधयोरसंभवात्सामर्थ्याद्विषयभेद आश्रयितव्य इति **प्रश्नः** ॥

(उद्योतः) **विभाषा दि० ॥ २८ ॥ एकस्मिन्निति** । सर्वत्र परत्वात्प्रतिषेधे विकल्पवैयर्थ्यम् । सर्वत्र वा विकल्पे भावाभावयोस्तेनैव सिद्धत्वात्प्रतिषेधानर्थक्यमिति तयोरेकविषयकत्वासंभव इति भावः ॥

(समाधानभाष्यम्)

"न बहुव्रीहौ" इति प्रतिषेधं वक्ष्यति, तत्र न ज्ञायते—क विभाषा क प्रतिषेध इति ॥ दिग्ग्रहणे पुनः क्रियमाणे न दोषो भवति—दिगुपदिष्टे विभाषा, अन्यत्र प्रतिषेधः ॥

(प्रदीपः) वचनमन्तरेणाभिमतो विषयभेदो न लभ्यत **इत्युत्तरम्** ॥

(उद्योतः) भाष्ये-**दिगुपदिष्टे इति** । दिक्शब्दोच्चारणेन विहित इत्यर्थः । बहुव्रीहाविति शेषः ॥

(आक्षेपभाष्यम्)

अथ समासग्रहणं किमर्थम् ?

(समाधानभाष्यम्)

समास एव यो बहुव्रीहिस्तत्र यथा स्यात्, बहुव्रीहिवद्भावेन यो बहुव्रीहिस्तत्र मा भूदिति । दक्षिणदक्षिणस्यै देहि ॥

(प्रदीपः) **समास एवेति** । मुख्य इत्यर्थः । अन्यस्तु तत्कार्यलाभात् तद्व्यपदेशं लभत इत्यमुख्यः ॥

(उद्योतः) व्याप्यधर्मातिदेशे व्यापकधर्मस्याप्यतिदेशात्समासोऽप्ययमत आह—**मुख्य इति** ॥ (भाष्ये)-**दक्षिणदक्षिणस्यै इति** । आबाधे चेति द्विर्वचनबहुव्रीहिवद्भावौ ॥

(आक्षेपभाष्यम्)

अथ बहुव्रीहिग्रहणं किमर्थम् ?

(समाधानभाष्यम्)

द्वन्द्वे मा भूत्—दक्षिणोत्तरपूर्वाणामिति ॥

(प्रदीपः) **दक्षिणोत्तरपूर्वाणामिति** । 'द्वन्द्वे च' इत्यनेन सर्वाद्यन्तस्य द्वन्द्वस्य सर्वनामसंज्ञाप्रतिषेधः, नावयवानाम्-इति 'सर्वनाम्नो वृत्तिमात्रे' इति पुंवद्भावः ॥

(उद्योतः) **नावयवानामिति** । **न बहुव्रीहाविति**वद् 'द्वन्द्वे चिकीर्षिते न' इत्यर्थो न । यद्यपि द्वन्द्वेऽपि उद्भूतावयवभेदसमुदायस्य प्राधान्येन तं प्रति बहुव्रीहेरिव द्वन्द्वस्य गुणत्वेन तदप्राप्तेरयमेवोचितः, तथापि त्यदादीनां द्वन्द्वाभावेनादन्ते काकचोरविशेषेण फलाभावात् । अन्यपर्यायत्वच्छब्दस्य सर्वनामत्वे न मानम्, बहुसंमतत्वाद् गणे तत्पाठस्य । **विभाषा जसीत्यस्या**सङ्गतेश्चेति भावः ॥ एवं चेदं **सूत्रमुपसर्जनप्रतिषेधानुवादकमेव** । सूत्रकृता तदनभ्युपगमाद्वा कृतं तत् । अत एव कुक्कुटमयूर्यावित्यादावुपसर्जनह्रस्वावारणाय द्वन्द्वे नेति वचनमारब्धं **"गोस्त्रियोः-"**इति सूत्रे भाष्ये इति बोध्यम् ॥ **पुंवद्भाव इति** । इदं चिन्त्यं, मात्रग्रहणेन सिद्धेः ॥

(समाधाननिराकरणभाष्यम्)

नैतदस्ति प्रयोजनम् । "द्वन्द्वे च" इति प्रतिषेधो भविष्यति ॥

(समाधानसाधकभाष्यम्)

नाप्राप्ते प्रतिषेधे इयं विभाषा आरभ्यते । सा यथैव "न बहुव्रीहौ" इत्येतं प्रतिषेधं बाधते, एवं "द्वन्द्वे च" इत्येतमपि बाधेत ॥

(समाधानबाधकभाष्यम्)

न बाधते ।

किं कारणम् ?

येन नाप्राप्ते तस्य बाधनं भवति । न चाप्राप्ते "न बहुव्रीहौ" इत्येतस्मिन्प्रतिषेधे इयं विभाषा आरभ्यते, "द्वन्द्वे च" इत्येतस्मिन् पुनः प्राप्ते चाप्राप्ते च ॥

(प्रदीपः) **येन नाप्राप्त इति** । अयमत्रार्थः-'न बहुव्रीहौ' इत्यनेन सर्वः स्वविषयो व्याप्तः । 'द्वन्द्वे च' इत्यनेन तु न व्याप्तः, 'विभाषा जसि' इति जसि विकल्पविधानात् ॥ यदि चानेन द्वन्द्वे विभाषा स्यात् जस्यनुवाददोषः प्रसज्येत । बहुव्रीहौ त्वनुवाददोषमलभमाना कृतार्था सती परत्वादियं विभाषा 'द्वन्द्वे च' इत्यनेन बाध्यते ॥

(उद्योतः) ननु यथा बहुव्रीहौ द्वन्द्वे चेत्यप्राप्तावपीयं प्रवर्तते, तथा द्वन्द्वे न बहुव्रीहावित्यप्राप्तेऽपि, इति किमुच्यते **न चाप्राप्ते** इतीत्यत आह—**अयमत्रार्थ इति** । एवं **न चाप्राप्ते** इत्यस्य भाष्ये बहुव्रीहावित्यादिः । **द्वन्द्वे चे**त्यस्य तु द्वन्द्वे-इत्यादिः ॥ एवं च बहुव्रीहौ सर्वत्र निषेधप्राप्तिः, द्वन्द्वे तु द्वन्द्वे चेत्यस्य न सर्वत्र प्राप्तिर्जसि विभाषया बाधादिति भावः ॥ **सर्वः स्वविषय इति** । सर्वो दिग्बहुव्रीहिरित्यर्थः ॥ **न व्याप्त इति** । सर्वो दिग्द्वन्द्व इति शेषः ॥ युक्त्यन्तरमप्याह—**यदि चेति** ॥

(समाधानबाधकान्तरभाष्यम्)

अथवा-"पुरस्तादपवादा अनन्तरान्विधीन् बा-

धन्ते, नोत्तरान्" इत्येवमियं विभाषा "न बहुव्रीहौ" इत्येतं प्रतिषेधं वाधिष्यते, "द्वन्द्वे च" इत्येतं प्रतिषेधं न बाधिष्यते ॥

(समाधानबाधकान्तरभाष्यम्)

अथ वा-इदं तावदयं प्रष्टव्यः—इह कस्मान्न भवति—या पूर्वा सोत्तरा अस्योन्मुग्धस्य सोऽयं पूर्वोत्तर उन्मुग्धः, तस्मै-पूर्वोत्तराय देहीति ?

लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैवेति ॥

(प्रदीपः) लक्षणप्रतिपदोक्तयोरिति । दिक्समास इति व्यपदेशः 'दिङ्नामानि' इति विहितस्य न्याय्यः, तत्र हि दिक्शब्दोऽस्ति ॥

(उद्द्योतः) भाष्ये-या पूर्वा सोत्तरेति ॥ यद्यपि वाक्ये यत्तच्छब्दाभ्यामुद्देश्यविधेयत्वं प्रतीयते-या पूर्वात्वप्रकारकज्ञानविशेष्या सा प्रसिद्धोत्तरा यस्य-इत्यर्थात् । एवं चोत्तराशब्दस्य पूर्वनिपातः प्राप्नोति, तथापि समासे तदप्रतीत्या पूर्वापदस्य ज्ञानविशेष्यपर्यन्तलक्षकत्वेन गुणवाचकत्वाद् विशेषणत्वेन पूर्वनिपात इति बोध्यम् ॥ तत्र हि दिक्शब्दोऽस्तीति । न च शेषग्रहणेनानेकग्रहणेन वा सिद्धे उभयोपादानेन पुनर्विधानद्वारा सर्वत्र विशेषविहितत्वात्सोऽपि प्रतिपदोक्तः, स्पष्टं चेदमान्महत इत्यत्र भाष्ये इति वाच्यम् । 'पूर्वशब्द उत्तरशब्दः समस्यते' इत्येवं विधानकल्पनेऽपि 'दिक्शब्दः समस्यते' इत्येवं विधानकल्पने मानाभावेन तत्र दिक्शब्दाभावादिति भावः ॥

(उपसंहारप्रत्याख्यानभाष्यम्)

यद्येवं नार्थो बहुव्रीहिग्रहणेन ॥

(आक्षेपभाष्यम्)

द्वन्द्वे कस्मान्न भवति ?

(समाधानभाष्यम्)

लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैवेति ॥

(प्रयोजनान्तरभाष्यम्)

उत्तरार्थं तर्हि बहुव्रीहिग्रहणं कर्तव्यम् ॥

(बाधकभाष्यम्)

न कर्तव्यम् । क्रियते तत्रैव—"न बहुव्रीहौ" इति ॥

(साधकभाष्यम्)

द्वितीयं कर्तव्यम् । बहुव्रीहिरेव यो बहुव्रीहिः, तत्र यथा स्यात् । बहुव्रीहिवद्भावेन यो बहुव्रीहिस्तत्र मा भूत्—एकैकस्मै देहि ॥

(बाधकभाष्यम्)

एतदपि नास्ति प्रयोजनम् । 'समासे' इति वर्तते, तेन बहुव्रीहिं विशेषयिष्यामः—समासो यो बहुव्रीहिरिति ॥

(एकदेशिभाष्यम्)

इदं तर्हि प्रयोजनम्—अवयवभूतस्यापि बहुव्रीहेः प्रतिषेधो यथा स्यात् । इह मा भूत्—वस्त्रमन्तरमेषां त इमे-वस्त्रान्तराः, वसनमन्तरमेषां त इमे-वसनान्तराः, वस्त्रान्तराश्च वसनान्तराश्च-वस्त्रान्तरवसनान्तराः ॥ २८ ॥

(प्रदीपः) वस्त्रान्तरेति । उपसर्जनप्रतिषेधो वार्तिककारस्य न सूत्रकारस्य, 'न बहुव्रीहौ' इत्यारम्भात् । तन्मतेनेदं प्रयोजनमुक्तम् ॥ २८ ॥

(उद्द्योतः) भाष्ये-अवयवभूतस्यापीति । प्रधानन्यायेनास्य न स्यात्, अस्य समूहं प्रति गुणत्वादिति भावः ॥ तदेतदवयवपदेन सूचितम् । समूहावयवत्वाद्वर्तिपदार्थस्येति बोध्यम् । वसनशब्दो गृहवाचीति नैकशेषः । अन्तरशब्दस्य सर्वनामत्वेऽपि परनिपातो राजदन्तादित्वाद् बोध्यः ॥ तन्मतेनेति । किं चावयवयोः सर्वनामत्वेऽपि द्वन्द्वस्य तत्त्वाभावेन सर्वनाम्नोऽविहितत्वाज्जसो न दोष इत्येकदेश्युक्तिरिदं भाष्यम् ॥ २८ ॥

(२७ सर्वनामसंज्ञानिषेधसूत्रम् ॥ १ । १ । ६ आ. ३)

न बहुव्रीहौ ॥ १ । १ । २९ ॥

(सूत्रप्रयोजनाधिकरणम्)

(प्रश्नभाष्यम्)

किमुदाहरणम् ?

(उत्तरभाष्यम्)

प्रियविश्वाय ॥

(प्रदीपः) न बहुव्रीहौ ॥ २९ ॥ प्रियविश्वायेति । प्रियशब्दस्य विश्वविशेषणत्वात्पूर्वनिपातं मन्यते ॥

(समाधानबाधकभाष्यम्)

नैतदस्ति प्रयोजनम् ।

सर्वाद्यन्तस्य बहुव्रीहेः प्रतिषेधेन भवितव्यम् । वक्ष्यति चैतत्—'*बहुव्रीहौ सर्वनामसंख्ययोरुपसंख्यानम्*' इति, तत्र विश्वप्रियायेति भवितव्यम् ॥

(समाधानान्तरभाष्यम्)

इदं तर्हि-द्व्यन्याय, त्र्यन्याय ॥

(प्रदीपः) द्व्यन्यायेति । संख्यायाः संख्येयपरतन्त्रत्वाद्विशेषणत्वम् ॥

(समाधानबाधकभाष्यम्)

ननु चात्रापि सर्वनाम्न एव पूर्वनिपातेन भवितव्यम् ॥

(प्रदीपः) सर्वनाम्न एवेति । नियमः कथमिति चेत्, उच्यते-विशेषणत्वात्संख्यायाः पूर्वनिपाते प्राप्ते, एवमर्थमुपसंख्यानं स्यात्—सर्वनामसंख्ययोः संनिपाते सर्वनाम्न एव पूर्वनिपातः स्यादिति ॥

(उद्द्योतः) न बहुव्रीहौ ॥ २९ ॥ नियमः कथमिति । संख्याया अपि तेन पूर्वनिपातविधानादिति भावः ॥ प्राप्ते इति । 'सप्तमीविशेषणे' इत्यनेन ॥

(समाधानसाधकभाष्यम्)

नैष दोषः । वक्ष्यत्येतत्–'संख्यासर्वनाम्नोर्यो बहुव्रीहिः परत्वात्तत्र संख्यायाः पूर्वनिपातो भवति' इति ॥

(प्रदीपः) वक्ष्यत्येतदिति । नैष वाक्यार्थो यस्त्वया कल्पित इत्यर्थः ॥

(उद्योतः) नैष इति । लक्ष्यानुरोधादिति भावः ॥ न चैवं वार्तिके संख्याग्रहणं व्यर्थं, विशेषणत्वादेव तस्य पूर्वनिपातप्राप्तेरिति वाच्यम् । परिच्छेदकत्वरूपविशेषणताया अन्यत्रापि संभवात् ॥

(पूर्वोक्तसमाधानाभ्युपगमभाष्यम्)

इदं चाप्युदाहरणम्—प्रियविश्वाय ॥

(बाधकस्मारणभाष्यम्)

ननु चोक्तम्—'विश्वप्रियायेति भवितव्यम्' इति ॥

(बाधकनिराकरणभाष्यम्)

वक्ष्यत्येतत्—*वा प्रियस्य* इति ॥

(सूत्रार्थान्तरप्रदर्शनभाष्यम्)

न खल्वप्यवश्यं सर्वाद्यन्तस्यैव बहुव्रीहेः प्रतिषेधेन भवितव्यम् ।

किं तर्हि ?

असर्वाद्यन्तस्यापि भवितव्यम् ।

किं प्रयोजनम् ?

अकच् मा भूदिति ॥

(उद्योतः) भाष्ये वृत्तिकारोक्तं सूत्रार्थमाह—न खल्वपीति । अस्यार्थस्य यथा लाभस्तथा वक्ष्यते ॥

(आक्षेपभाष्यम्)

किंच स्यात् ?

(समाधानभाष्यम्)

यद्यत्राकच् स्यात्, को न स्यात् ॥

(आक्षेपभाष्यम्)

कश्चेदानीं काकचोर्विशेषः ?

(समाधानभाष्यम्)

व्यञ्जनान्तेषु विशेषः—अहकं पिता अस्य–अहकत्पितृकः, त्वकं पिता अस्य–त्वकत्पितृक इति प्राप्नोति ।

अस्मत्पितृकः-त्वत्कपितृक इति चेष्यते ॥

(प्रदीपः) व्यञ्जनान्तेष्विति । उपलक्षणमेतत् । 'द्विकपुत्रः' 'द्वकिपुत्रः' इत्यत्रापि विशेषदर्शनात् ॥

(आक्षेपभाष्यम्)

कथं पुनरिच्छताऽपि भवता बहिरङ्गेण प्रतिषेधेनान्तरङ्गो विधिः शक्यो बाधितुम् ?

(प्रदीपः) कथं पुनरिति । अन्तरङ्गत्वात्संज्ञानिमित्तो नाकचा तावद्भाव्यं, पश्चात्पदान्तरसंनिधाने वर्तिपदार्थविशेषणान्यपदार्थविवक्षायां बहिरङ्गेण बहुव्रीहिणेत्यर्थः ॥

(उद्योतः) बहिरङ्गत्वव्युत्पादनाय–'पदान्तरे'त्यादि । वर्तिपदार्थविशेषणेति बहुव्रीहिः ॥ बहुव्रीहिणेति । ततो बहिरङ्गबहुव्रीहिनिमित्तकेन निषेधेनेति शेषः ॥

(समाधानभाष्यम्)

'अन्तरङ्गानपि विधीन् बहिरङ्गो विधिर्बाधते' गोमत्प्रिय इति यथा ॥

(प्रदीपः) अन्तरङ्गानपीति । 'प्रत्ययोत्तरपदयोश्च' इति सामान्येन ज्ञापकम्–'बहिरङ्गोऽपि समासाश्रयो विधिरन्तरङ्गं बाधते' इत्यस्यार्थस्येति भावः ॥

(उद्योतः) सामान्येनेति । न लुग्विषयमेवेति भावः ॥

(दृष्टान्तवैषम्येण समाधानबाधकभाष्यम्)

क्रियते तत्र यत्नः—"प्रत्ययोत्तरपदयोश्च" इति ॥

(प्रदीपः) क्रियते तत्रेति । लुग्विषयमेव तत् ज्ञापकमित्यर्थः ॥

(उद्योतः) उत्तरपदग्रहणं चात्र ज्ञापकं, अन्तर्वर्तिलुपा प्रत्ययपरत्वेनैव सिद्धेः–इत्यादि सप्तमे निरूपयिष्यामः ॥ गोमत्प्रिय इत्यत्र तु हल्ङ्यादिलोपो बाध्यते, तेन नुम्दीर्घौ नेति भावः ॥

(दृष्टान्तसाम्येन समाधानसाधकभाष्यम्)

ननु चेहापि क्रियते—"न बहुव्रीहौ" इति ॥

(उद्योतः) भाष्ये—ननु चेहापीति । वैयधिकरण्येन संबन्धाश्रयणसामर्थ्यादन्तरङ्गस्यापि निवृत्तिरित्यर्थः ॥

(वैयर्थ्यपरिहारेण समाधानबाधकभाष्यम्)

अस्त्यन्यदेतस्य वचने प्रयोजनम् ॥

किम् ?

प्रियविश्वाय ॥

(प्रदीपः) अस्त्यन्यदिति । अत्र हि विधिप्रतिषेधौ समानकालौ, कार्यकालत्वात्संज्ञाया इति मन्यते ॥

(उद्योतः) प्रथमार्थे सप्तम्याश्रयणेन सामानाधिकरण्येनैव संबन्धो न तु विषयत्वाध्याहारेणेत्याशयेनाह—अस्त्यन्यदिति ॥ अत्र हीति । बहुव्रीहेर्विभक्त्युत्पत्तौ सर्वनामकार्यस्यायावप्राप्तेरिति भावः ॥ तत्रावयवनिषेधसामर्थ्यादन्तरङ्गस्यापि बाध इति तात्पर्यम् ॥

(वैयर्थ्यस्थित्या समाधानसाधकभाष्यम्)

उपसर्जनप्रतिषेधेनाप्येतत्सिद्धम् ॥

(मतान्तरेण समाधानान्तरभाष्यम्)

अयं खल्वपि बहुव्रीहिरस्त्येव प्राथमकल्पिकः, यस्मिन्नैकपद्यमैकस्वर्यमेकविभक्तित्वं च ।

अस्ति तादर्थ्यात्ताच्छब्द्यम्, बहुव्रीह्यर्थानि पदानि–बहुव्रीहिरिति ।

तद्यस्तादर्थ्यात्ताच्छब्द्यं तस्येदं ग्रहणम् ॥

(प्रदीपः) अयं खल्वपीति । सूत्रोपारूढ एवायमर्थ इति प्रतिपादयति । अप्रयोगसमवायि यत् प्रक्रियावाक्यं तत्रायं प्रतिषेधः । न लौकिके वाक्ये प्रयोगार्हे, तस्य पृथगेव प्रयोगात्तादर्थ्याभावात् ॥

(उद्योतः) ननु एतत्प्रकरणस्थसप्तमीनिर्देशाः प्रथमार्थाः । अत एव द्वन्द्वे चेति निषेधः समुदायस्यैव । एवं च वाच्यवृत्त्याऽसर्वादन्तस्य निषेधो न लभ्यत इत्यत आह—भाष्ये—अयं खल्वपीति । एतेन बहुव्रीहावित्यत्र 'चिकीर्षिते' इत्यध्याहारेण सिद्धे बहुव्रीहिपदस्य लक्षणा व्यर्थेति परास्तम् ॥ तथ्याचष्टे—सूत्रेति । भाष्ये—ऐकपद्यं-एकार्थीभावः । एककारकशक्तियोगो वा—एकविभक्तित्वं बोध्यम् ॥ तादर्थ्यात्ताच्छब्द्यं यत्=यो लभते तस्येदं ग्रहणमित्यन्वयः ॥ 'तपत्र तादर्थ्यात्' इति पाठः क्वचित् । तत्र बहुव्रीह्यर्थवाक्ये संज्ञाया अप्राप्त्या तत्स्थपदपर्यन्तं लक्षणा बोध्या । तदेतद्बहुव्रीह्यर्थानि पदानीत्यनेन सूचितम् ॥ ननु वाक्ये निषेधश्चेत् 'अहकं पिता' इति प्रयोगो न स्यात्, किं च सुपरत्वाभावात्त्वादी न स्यातामत आह—अप्रयोगेति ॥

(प्रत्याख्यानभाष्यम्)

गोनर्दीयस्त्वाह—

'अकच्स्वरौ तु कर्तव्यौ प्रत्यङ्गं मुक्तसंशयम् ।'
त्वकत्पितृको मकत्पितृक इत्येव भवितव्यमिति ॥

(प्रदीपः) गोनर्दीयस्त्वाहेति । सूत्रप्रत्याख्यानमेतत् । यथोत्तरं हि मुनित्रयस्य प्रामाण्यम् ॥ स्वरः—'स्वाङ्गशिटामदन्तानाम्' इत्याद्युदात्तत्वम् ॥

(उद्योतः) तदेतद्वृत्तिकारोक्तं दूषयति—अकच्स्वरौ त्विति । एषा स्मृतिरविशेषात्सर्वप्रकरणविषया ॥ सूत्रप्रत्याख्यानेति । समुदाये निषेधस्य महासंज्ञया, उपसर्जनप्रतिषेधेन वा सिद्धत्वादिति भावः ॥ एवंच महासंज्ञासिद्धार्थानुवादकं प्रपञ्चार्थं सूत्रम् । एवं द्वन्द्वे चेत्यपि सूत्रमिति सूत्रद्वयम् ॥ यथोत्तरमिति । उत्तरोत्तरस्य बहुलक्ष्यदर्शित्वात् । स्पष्टं चेदं धिन्विकृण्व्योरिति सूत्रे भाष्ये ॥ एतेन सूत्रसार्थक्याय वृत्तिकारोक्तं व्याख्यानमेव प्रबलमित्यपास्तम् ॥ शिडिति सर्वनाम । स्वरोदाहरणं—विश्वप्रियायेति ॥

—०—

(न्यूनतापरिहाराधिकरणम्)

(२०१ उपसंख्यानवार्तिकम् ॥ १ ॥)

॥ ॐ ॥ प्रतिषेधे भूतपूर्वस्योपसंख्यानम् ॥ ॐ ॥

(भाष्यम्)

प्रतिषेधे भूतपूर्वस्योपसंख्यानं कर्तव्यम् । आढ्यो भूतपूर्वः—आढ्यपूर्वः, आढ्यपूर्वाय देहीति ॥

(प्रदीपः) आढ्यपूर्वायेति । अबहुव्रीह्यर्थं वचनम् ॥

(उद्योतः) भाष्ये—भूतपूर्वस्येति । भूतपूर्वार्थकपूर्वान्तस्य समासस्येत्यर्थः ॥

(२०२ उपसंख्यानानर्थक्ये वार्तिकम् ॥ २ ॥)

॥ ॐ ॥ प्रतिषेधे भूतपूर्वस्योपसंख्यानानर्थक्यं पूर्वादीनां व्यवस्थायामिति वचनात् ॥ ॐ ॥

(भाष्यम्)

प्रतिषेधे भूतपूर्वस्योपसंख्यानमनर्थकम् ।

किं कारणम् ?

'पूर्वादीनां व्यवस्थायामितिवचनात् ।' पूर्वादीनां व्यवस्थायां सर्वनामसंज्ञोच्यते । न चात्र व्यवस्था गम्यते ॥ २९ ॥

(प्रदीपः) न चात्रेति । प्राधान्येनेति भावः । अत्र हि पूर्वत्वमाढ्यत्वस्य विशेषणम् । यथा—'अतिपूर्वाय' इति पूर्वार्थोऽतिक्रान्तस्य—इत्युपसर्जनत्वात्पूर्वार्थस्य न भवति संज्ञा । मयूरव्यंसकादित्वाच्चात्र समासः ॥ २९ ॥

(उद्योतः) प्राधान्येनेति । प्रयोगकालरूपस्यावधेर्शटिति बोधेन व्यवस्थासत्त्वेऽपि पूर्वार्थस्योपसर्जनत्वान्न भवतीति भावः ॥ २९ ॥

—०—

(२८ सर्वनामसंज्ञानिषेधसूत्रम् ॥ १।१।६ आ. ४ ॥)

तृतीयासमासे ॥ १ । १ । ३० ॥

(अर्थसाधनाधिकरणम्)

(आक्षेपभाष्यम्)

'समासे' इति वर्तमाने पुनः समासग्रहणं किमर्थम् ?

(समाधानभाष्यम्)

अयं तृतीयासमासोऽस्त्येव प्राथमकल्पिकः, यस्मिन्नैकपद्यमैकस्वर्यमेकविभक्तिकत्वं चेति ।

अस्ति तादर्थ्यात्ताच्छब्द्यम्, तृतीयासमासार्थानि पदानि—तृतीयासमास इति । यत्तादर्थ्यात्ताच्छब्द्यं तस्येदं ग्रहणम् ॥

(प्रदीपः) तृतीयासमासे ॥ ३० ॥ अत्र तादर्थ्यात्ताच्छब्द्यलाभे सति प्रयोगार्हस्य लौकिकस्य वाक्यस्य ग्रहणे सति 'मासेन पूर्वाय' इति प्रयोगः साधुः । वाक्यभेदेन च मुख्ये समासे निषेधः ॥

(उद्योतः) तृतीया० ॥ ३० ॥ अयमपि समुदायनिषेध एव—सर्वाद्यन्ततृतीयासमासः सर्वनाम नेत्यर्थः ॥ प्रयोगार्हस्येति । 'मासेन पूर्वाय देहि' इति भाष्योदाहरणादिति भावः ॥ भाष्ये—तादर्थ्यादिति च लोकदृष्ट्योक्तम् । लोको हि समासेन वाक्यार्थं वृत्तिं निष्पन्नां मन्यते ॥ नन्वेवं सति समुदायस्य निषेधो न लभ्यतेऽत आह—वाक्यभेदेन चेति । आवृत्त्येति भावः ॥

(समाधानान्तरभाष्यम्)

अथवा 'समासे' इति वर्तमाने पुनः समासग्र-

णस्यैतत्प्रयोजनम्—योगाङ्गं यथोपजायेत । सति च योगाङ्गे योगविभागः करिष्यते—"तृतीया" तृतीयासमासे सर्वादीनि सर्वनामसंज्ञानि न भवन्ति । मासपूर्वाय देहि, संवत्सरपूर्वाय देहि ॥

ततः—"असमासे" असमासे च तृतीयायाः सर्वादीनि सर्वनामसंज्ञानि न भवन्ति । मासेन पूर्वाय देहि ॥ ३० ॥

(प्रदीपः) अथवेति । पर्युदासाश्रयणात्समाससदृशस्य वाक्यस्य ग्रहणम् । पूर्वसदृशेति च प्रतिपदोक्तस्तृतीयासमासो गृह्यते ॥ ३० ॥

(उद्योतः) (भाष्ये)—अथवेति—योगाङ्गमिति । योगरूपमङ्गमष्टाध्याय्या इत्यर्थः ॥ तृतीयासमासे सर्वादीनीति । तृतीयासमासरूपाणि सर्वाद्यन्तानीत्यर्थः । अन्यथा पूर्वशब्दस्य निषेधेऽपि समासस्य तदनिषेधादुदाहरणे स्मै स्यात् । अवयवस्य तत्त्वेऽपि ततो विभक्तेरविहितत्वान्न दोषः । सप्तम्युच्चारणं तु सूत्रानुरोधादिति बोध्यम् ॥ तृतीयायाः सर्वादीनीति । तृतीयान्तात्पराणीत्यर्थः ॥ तद्बीजं दर्शयति—पर्युदासेति । भाष्ये पञ्चम्युपादानात्पूर्वपदभूते नास्य प्रवृत्तिः ॥ सदृशस्येति । प्रयोगार्हत्वेन समाससमानपदार्थकत्वेन च सादृश्यम् ॥ प्रतिपदोक्त इति । तेन 'मासेन कृताय पूर्वस्मै' इत्यत्र तदर्थके 'मासपूर्वस्मै' इत्यत्र च न दोषः । अत एव भाष्ये प्रथमोपस्थितानन्यान्सर्वादीन्विहाय पूर्व एवोदाहृत इति बोध्यम् ॥ ३० ॥

(२९ द्वन्द्वे सर्वनामसंज्ञाविकल्पसूत्रम् ॥ १।१।६ आ. ५)

विभाषा जसि ॥ १ । १ । ३२ ॥

(अर्थप्रदर्शनाधिकरणम्)

(भाष्यम्)

जसः कार्यं प्रति विभाषा । अकज्झि न भवति ॥ ३२ ॥

(प्रदीपः) विभाषा ज० ॥३२॥ जसःकार्यं प्रतीति । जस इः—जसीति निर्देशादिकारेण इकारस्य ग्रहणादित्याहुः । अन्ये तु कार्यकालत्वात्संज्ञाया जसः शीत्यत्रैवोपस्थानं मन्यन्ते ॥ ३२ ॥

(उद्योतः) विभाषा ज० ॥३२॥ इकारेणेति । तद्रूपस्य सर्वनामकार्यस्याभावात्—इति भावः ॥ सूत्रे जसीति च लुप्तसप्तमीकं लुप्तद्वितीयान्तं वा ॥ अन्ये त्विति । जसीत्यस्य च जसघटिते सर्वनामकार्यविधायकसूत्रे द्वन्द्वे विभाषेति संज्ञाविकल्पायोपतिष्ठते-इत्यर्थ इत्यभिमानः ॥ भाष्ये—अकज्झि न भवतीत्यस्य समुदायनिष्ठकुत्साद्योतकोऽकच्न भवतीत्यर्थः । कृताकचा समासस्तु भवत्येव, तत्र सर्वाद्यन्तत्वादनेन विकल्पो भवत्येव । समुदायकुत्साविवक्षायां केनायं विकल्पः, द्वन्द्वस्य सर्वाद्यन्तत्वाभावादिति बोध्यम् ॥ ३२ ॥

(३० जसि सर्वनामसंज्ञाविकल्पनसूत्रम् ॥ १।१।६आ.६)

पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम् ॥ १ । १ । ३४ ॥

(गण-सूत्रपाठयोः कालनिर्णयाधिकरणम्)

(२०३ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ अवरादीनां च पुनः सूत्रपाठे ग्रहणानर्थक्यं गणे पठितत्वात् ॥ * ॥

(भाष्यम्)

अवरादीनां च पुनः सूत्रपाठे ग्रहणमनर्थकम् । किं कारणम् ?

'गणे पठितत्वात्' । गणे ह्येतानि पठ्यन्ते ॥

(प्रदीपः) पूर्वपरा० ॥ ३४ ॥ अवरादीनां चेति । किमर्थं प्रतिपदं पूर्वादीनि जसि विभाषार्थं पठितानि, यावता गण एवार्थविशेषेण विशिष्टानि नित्यं सर्वनामसंज्ञार्थं पठ्यन्ते । तत्र पूर्वादीनि नवेत्येवं सूत्रं पठितव्यम् । प्राप्तविभाषा चेयं भविष्यति । तेषामेवात्र प्रत्यभिज्ञानात् । गण एवार्थनिर्देशः पाठविशेषण भविष्यति । यथा तिङो गोत्रादीनीत्यत्र कुत्सनाभीक्ष्ण्यग्रहणं गोत्रादिपाठविशेषणमिति वार्तिककाराभिप्रायः ॥ अवरादीनामित्यत्र प्रकारार्थ आदिशब्दः, तेन पूर्वपरशब्दावपि गृह्येते ॥

(उद्योतः) पूर्वपरा० ॥ ३४ ॥ भाष्ये—पुनः सूत्रपाठे इति । गणपाठोत्तरकालिके सूत्रपाठे इत्यर्थः ॥ ननु पूर्वादीनि नवेत्येतावत्युक्ते गणस्थग्रहणेन प्राप्तायाभावात्वेऽभावतात्पर्यकत्वेन गौरवादर्थान्तरे एवाप्राप्तविभाषा स्यादत आह—तेषामेवात्रेति ॥ नन्वेवमर्थविशेषलाभो न स्यादत आह—गणे एवेति ॥ प्रकारार्थ इति । वस्तुतो ल्पाक्षरत्वादजाद्यन्तत्वाच्च सूत्रेऽवरशब्दस्यैव पूर्वनिपात उचित इत्याशयेनावरादीनामित्युक्तिर्वार्तिककृत इति बोध्यम् ॥

(आक्षेपबाधकभाष्यम्)

कथं पुनर्ज्ञायते—स पूर्वः पाठः, अयं पुनः पाठ इति ?

(प्रदीपः) कथं पुनरिति । पूर्वं गणपाठो नियतसंनिवेशो व्यवस्थितः पश्चात्तु सूत्रपाठ इत्यत्र प्रमाणाभावात् । आदिशब्दः प्रकारवाची दृष्टः, व्यवस्थावाची च । तत्र सर्वादीनीत्यत्रादिशब्दस्य प्रकारार्थताऽपि संभवति । प्रकारार्थप्रदर्शनाय पश्चादभियुक्ता गणान् पठन्ति । यदुक्तम्—श्रेण्यादयः पठ्यन्ते कृतादिराकृतिगण इति ॥ कृतादयश्च वृत्तिकारैर्निदर्शनार्थं पठिताः । तत्र वेदे मध्यमस्यामवमस्यामिति प्रयोगदर्शनात्प्रकारार्थता आदिशब्दस्य सर्वादीनीत्यत्र संभाव्यत इति प्रश्नः ॥

(उद्द्योतः) ननु 'सर्वादीनि' इति व्यवहाराद् गणपाठस्य पूर्वता निश्चीयतेऽत आह—आदिशब्द इति ॥ ननु गणपाठस्य निदर्शनार्थत्वे आदिपदस्य प्रकारार्थता स्यात्, तदेव कुत इत्यत आह—तत्र चेद इति ॥ प्रकारेति । सर्वनामकार्यवत्त्वमेव सादृश्यमिति भावः ॥

(आक्षेपसाधकभाष्यम्)

तानि हि पूर्वादीनि, इमान्यवरादीनि ॥

(प्रदीपः) **तानि हि पूर्वादीनीति** । पूर्वकालपठितत्वात्पूर्वशब्देन सर्वशब्दोऽभिधीयते । तेनायमर्थः—**सर्वादीनी**त्यत्र व्यवस्थावाच्यादिशब्दः । प्रकारवाचित्वे हि कृत्स्नादीनामपि संज्ञा स्यात् । मध्यमस्यामवमस्यामिति तु व्यत्ययेन छान्दसः प्रयोगः ॥ **इमान्यवरादीनीति** । अवरकालपाठात्पूर्वशब्दोऽवरशब्देनोच्यते ॥ तेन पूर्वं गणपाठः, पश्चात्सूत्रपाठ इत्यर्थः ॥

(उद्द्योतः) छान्दसः प्रयोग इति । एवं च सर्वादीनीति व्यवहारादेव गणपाठस्य पूर्वत्वनिश्चय इति भावः ॥ अत्र वदन्ति—तानि पूर्वादीनीत्यनेनैव गणपाठस्य पूर्वत्वे सिद्धे, इमान्यवरादीनीति व्यर्थम् । अस्य हि पूर्वादीनीत्यर्थः कैयटाछभ्यते । न चायं सूत्रपाठस्य पुनः पाठत्वे साधकः । किं चेमान्यपि पूर्वादीनीति शङ्काऽप्यनुपपन्ना, त्वदुक्तरीत्या हेतोरभिधानात् । एवं च हेत्वभिधानमन्तरेणेत्याद्यपि चिन्त्यमेव । तस्मादत्रादिशब्द आश्रयवाची, भीष्मादिश्च सुयोधन इतिवत् ॥ तानि=गणपठितानि पूर्वकालाश्रयाणि, इमानि=अष्टाध्यायीपठितानि अवरकालाश्रयाणीत्यर्थः । एवं च तत्तत्कालकृतत्वात्पूर्वादिव्यवहार इति भावः ॥

(आक्षेपबाधकभाष्यम्)

इमान्यपि पूर्वादीनि ॥

(प्रदीपः) हेत्वभिधानमन्तरेणाशक्योऽयमर्थः प्रतिपत्तुमित्याह—**इमान्यपीति** ॥

(उद्द्योतः) तत्र मानाभावमूलकं शङ्कते—इमान्यपि—अष्टाध्यायीपठितान्यपि ॥ पूर्वादीनि—पूर्वकालाश्रयाणीत्यर्थः ॥ अत्रापिरेवार्थे । अन्यथोभयोः परस्परापेक्षया पूर्वकालत्वासंभवेनाऽपिरनर्थक एव स्यात् ॥ सर्वादीनीत्यादौ सर्वत्रादिशब्दः प्रकार एव ॥ तत्तत्कार्यवत्त्वेन च सादृश्यम् । अतिप्रसङ्गस्त्वनभिधानान्नेत्याशयः ॥ ध्वनितं चेदं कस्येद्विति सूत्रे भाष्ये-इति ॥

(आक्षेपसाधकभाष्यम्)

एवं तर्ह्याचार्यप्रवृत्तिर्ज्ञापयति—स पूर्वः पाठः, अयं पुनः पाठः-इति । यदयं "पूर्वादिभ्यो नवभ्यो वा" इति नवग्रहणं करोति । नवैव हि पूर्वादीनि ॥

(प्रदीपः) **नवग्रहणमिति** । तत्र हि नवग्रहणं त्यदादिनिरासार्थं क्रियते । यदि च नियतसंनिवेशो गणपाठः पूर्वस्ततोऽधिकव्यवच्छेदाय नवग्रहणं कर्तव्यम् ॥

(उद्द्योतः) नवैवेति-भाष्ये । अष्टाध्याय्यां पूर्वेत्यादित्रिसूत्रीपठितानीत्यर्थः । अष्टाध्याय्याः पूर्वकालत्वे पूर्वादीति सूत्रेऽष्टाध्यायीसूत्रपठितानामेव तेषां ग्रहणं स्यादिति भावः ॥

(समाधानभाष्यम्)

इदं तर्हि प्रयोजनम्—व्यवस्थायामसंज्ञायामिति वक्ष्यामीति ॥

(प्रदीपः) **इदं तर्हीति** । प्रतिनियतविशेषणाभिधानाय प्रतिपदपाठ इत्यर्थः ॥

(उद्द्योतः) प्रतिनियतेति । पूर्वादिसप्तकस्यैव व्यवस्थायामित्यादि, स्वशब्दस्यैवाज्ञातीत्यादि, अन्तरशब्दस्यैव बहिर्योगेत्यादि-विशेषणाभिधानायेत्यर्थः ॥

(समाधानबाधकभाष्यम्)

एतदपि नास्ति प्रयोजनम् । एवंविशिष्टान्येवैतानि गणे पठ्यन्ते ॥

(प्रदीपः) **एवंविशिष्टान्येवेति** । पाठविशेषणाय गणेऽर्थनिर्देश इत्यर्थः ॥

(समाधानभाष्यम्)

इदं तर्हि प्रयोजनम्—त्यादिपर्युदासेन पर्युदासो मा भूदिति ॥

(प्रदीपः) **त्यादिपर्युदासेनेति** । त्यदादीनि पठित्वा गणे कैश्चित् पूर्वादीनि पठितानि, तत्राद्व्यादिभ्य इति तसिलादीनां प्रतिषेधः प्राप्नोति । तत्र पुनः सर्वनामसंज्ञया तसिलादिर्विधीयते । तेन द्व्यादिपर्युदासो बाध्यते । यथा 'अनुर्लक्षणे' इति पुनर्विधानेन **हेतुतृतीया** बाध्यते । वाक्यभेदेन च विभाषा जसि विधीयते । यथा '**अभि पूर्वः**' '**संप्रसारणाच्च**' इत्यत्र वाक्यभेदेन '**वा छन्दसि**' इति संबन्धाच्छन्दसि विकल्पः क्रियते इति भावः ॥

(उद्द्योतः) अष्टाध्यायीपाठेन यथा त्यादिपर्युदासाभावस्तथा दर्शयति-तत्र पुनरिति । पुनः संज्ञाविधानेन पुनः कार्यविधानद्वारा त्यादिपर्युदासो बाध्यत इत्यर्थः ॥ इति पुनर्विधानेनेति । एतत्संज्ञाकल्पितेन द्वितीयापुनर्विधानेनेत्यर्थः ॥ नन्वेवं जसि विकल्पो न स्यादत आह—वाक्यभेदेन चेति । विभाषा जसीत्यनुवृत्त्येत्यर्थः ॥

(समाधानबाधकभाष्यम्)

एतदपि नास्ति प्रयोजनम् । आचार्यप्रवृत्तिर्ज्ञापयति—नैषां त्यादिपर्युदासेन पर्युदासो भवतीति । यदयं "पूर्वत्रासिद्धम्" इति निपातनं करोति ।

वार्तिककारश्च पठति-*जश्भावादिति चेदुत्तरत्र ह्रस्वाभावादपवादप्रसङ्गः* इति ॥

(उद्द्योतः) जश्भावादिति चेदुत्तरत्रेति । ढोढे लोप इति सूत्रे वार्तिकमिदम् । एतैश्च सूत्रवार्तिकप्रयोगैस्त्यदादितः पूर्वमेव गणे पूर्वादिपाठ इति बोध्यत इति भावः ॥

(समाधानभाष्यम्)

इदं तर्हि प्रयोजनम्-जसि विभाषां वक्ष्यामीति ॥ ३४ ॥

(प्रदीपः) **इदं तर्हीति** । यदि पूर्वादीनि गणे उच्येत तदा गणपाठेऽर्थनिर्देशस्य नित्यसंज्ञाविधान एवोपयुक्तत्वात्

पाठविशेषणे प्रमाणाभावादप्राप्तविभाषेयमर्थान्तरे पूर्वादीनां असि विज्ञायेत, प्राप्तविभाषायामुक्तानुवाददोषप्रसङ्गादप्राप्तविभाषायाम-पूर्वविधानात् ॥ विभाषामिति । प्राप्तविभाषामित्यर्थः । प्रतिपदपाठं चान्तरेणासंकरेणार्थनिर्देशोऽशक्यः कर्तुमिति भाष्यकारेण प्रतिपदपाठः समर्थितः ॥ ३४ ॥

(उद्योतः) पाठविशेषणे प्रमाणाभावादिति । व्याख्यानातिरिक्तप्रमाणाभावादिति भावः ॥ तथाव्याख्याने बाधकमाह—उक्तानुवादेति । भागांशे—इत्यर्थः ॥ अभावतात्पर्यकत्वेन गौरवं दोष इत्यपि बोध्यम् ॥ नन्वप्राप्तविभाषात्ववारणायार्थमात्रनिर्देशः क्रियतां किं प्रतिपदपाठेनेत्यत आह—प्रतिपदेति ॥ असंकरेणेति । सप्तस्वेव व्यवस्थासंबन्धः, स्वे अज्ञातिधनयोः, अन्तरे बहिर्योगादेरित्येवं रूप इत्यर्थः ॥ एवमप्यापसूत्रे पूर्वादीनि व्यवस्थायामसंज्ञायामित्येव कुतो न सूत्रितम्, सप्तानामेव व्यवस्थायां वृत्तेरिति चिन्त्यम् ॥ ३४ ॥

—०—

(३१ सर्वनामसंज्ञाविकल्पनसूत्रम् ॥ १ । १ । ६ आ. ७)

स्वमज्ञातिधनाख्यायाम् ॥ १ । १ । ३५ ॥

(आख्याप्रयोजनाधिकरणम्)

(आक्षेपभाष्यम्)

आख्याग्रहणं किमर्थम् ?

(प्रदीपः) स्वमज्ञा० ॥ ३५ ॥ आत्मात्मीयज्ञातिधनवचनः स्वशब्दः । आत्मनिजविषयस्त्वैश्वर्यवाची ॥ आख्याग्रहणमिति । स्वे पुत्राः स्वे गाव इत्यत्र स्वशब्द आत्मीयत्वमेवाह । पुत्रादिशब्दास्तु ज्ञातिधनयोर्वर्तन्ते, न स्वशब्द इति प्रतिषेधो न भविष्यतीति प्रश्नः ॥

(उद्योतः) स्वमज्ञाति० ॥ ३५ ॥ आत्मीयत्वमेवाहेति । आत्मीयत्वेनैव ततः प्रतीतिर्न तु धनत्वादिनेत्यर्थः ॥

(समाधानभाष्यम्)

ज्ञातिधनपर्यायवाची यः स्वशब्दस्तस्य यथा स्यात्, इह मा भूत्—स्वे पुत्राः-स्वाः पुत्राः, स्वे गावः-स्वाः गावः ॥ ३५ ॥

(प्रदीपः) तस्य यथा स्यादिति । प्रतिषेध इति शेषः ॥ इह मा भूदिति । असत्याख्याग्रहणे स्वे पुत्रा इत्यादौ स्यादेव प्रतिषेधः । अत्राप्यात्मीयत्वं प्रवृत्तिनिमित्तमुपादाय स्वशब्दो ज्ञातिधनयोर्वर्तते, पुत्रादिभिः सामानाधिकरण्यात् । आख्याग्रहणे तु सति न दोषः । स्वशब्दो ह्यत्रात्मीयस्याख्या, न तु ज्ञातिधनयोरिति विधिः सिद्धः ॥ ३५ ॥

(उद्योतः) ईदृशविशेषलाभार्थमेवाख्याग्रहणम् । तदभावे आत्मीयत्वादिना ज्ञातिधनवाचकेऽपि निषेधः स्यादित्युत्तरम् ॥ प्रतिषेध इति शेष इति । अज्ञातीत्यादिप्रतिषेध इत्यर्थः ॥ न तु ज्ञातिधनयोरिति । ज्ञातित्वधनत्वयोरित्यर्थः ॥ ३५ ॥

—०—

(३२ सर्वनामसंज्ञाविकल्पनसूत्रम् ॥ १ । १ । ६ आ. ८)

अन्तरं बहिर्योगोपसंव्यानयोः ॥ १ । १ । ३६ ॥

(उपसंव्यानग्रहणप्रयोजनाधिकरणम्)

(२०४ प्रत्याख्यानाक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ उपसंव्यानग्रहणानर्थक्यं बहिर्योगेन कृतत्वात् ॥ * ॥

(भाष्यम्)

उपसंव्यानग्रहणमनर्थकम् ।

किं कारणम् ?

'बहिर्योगेण कृतत्वात्' । बहिर्योग इत्येव सिद्धम् ॥

(प्रदीपः) अन्तरम्० ॥ ३६ ॥ बहिरित्यनावृतो देश उच्यते, तेन योगो बहिर्योगः । स च बाह्यस्य भवतीति अन्तरे गृहा इति नगरबाह्याश्चण्डालादिगृहा उच्यन्ते । यदा तु बहिश्शब्देन बाह्य उच्यते, बाह्येन योगो बहिर्योग इति, तदा नगराभ्यन्तरे ये गृहास्त उच्यन्ते । उभयथाऽपि स्मर्यते । उपसंव्यानशब्दोऽपि कर्मकरणार्थभेदाद्भिन्नार्थः । ततः सर्वथा बहिर्योगात् सिद्धिं मत्वाऽऽह—उपसंव्यानेति ॥

(उद्योतः) अन्तरम्० ॥ ३६ ॥ भिन्नार्थ इति । नानार्थ इत्यर्थः ॥ ततः सर्वथेति । कर्मणि द्वितीयव्याख्यानेन, करणे आद्यव्याख्यानेनेति बोध्यम् ॥

(२०५ प्रत्याख्यानबाधकवार्तिकम् ॥ २ ॥)

॥ * ॥ न वा शाटकयुगाद्यर्थम् ॥ * ॥

(भाष्यम्)

न वाऽनर्थकम् ।

किं कारणम् ?

[शाटकयुगाद्यर्थम् ।] शाटकयुगाद्यर्थं प्रतिहीदं स्यात् । यत्रैतन्न ज्ञायते—किमन्तरीयं किमुत्तरीयमिति ॥

(प्रदीपः) न वेति । समानप्रमाणे शाटकयुगे अपरिहिते इदं न ज्ञायते—किमुत्तरीयं किमन्तरीयमिति, तदर्थमेतदित्यर्थः ॥

(उद्योतः) नन्वल्पमहत्परिमाणाभ्यामन्तरीयोत्तरीयत्वनिर्णयो भविष्यतीत्यत आह—समानेति । पदत्रयमपि सप्तम्यन्तम् ॥ भाष्ये—किमुत्तरीयं किमन्तरीयमित्येतन्न ज्ञायत इत्यन्वयः ॥

(प्रत्याख्यानसाधकभाष्यम्)

अत्रापि य एष मनुष्यः प्रेक्षापूर्वकारी भवति, निर्ज्ञातं तस्य भवति—इदमन्तरीयं इदमुत्तरीयमिति ॥

(प्रदीपः) अत्रापीति । यथोपसंव्यानत्वं भाविबुद्ध्या व्यवस्थाप्यते तथा बहिर्योगोऽपीत्यर्थः ॥ अन्ये त्वाहुः—आदिशब्दो वार्तिके शाटकयुगाद्यर्थमित्यत्रोपात्तः । तत्र शाटकानां त्रये चतुष्टये वा तृतीयचतुर्थयोर्बहिर्योगाभावादुपसंव्यानग्रहणं कर्तव्यम् ॥

(उद्योतः) तृतीयचतुर्थयोरिति। शरीरसंयुक्तयोरित्यर्थः॥ भाष्यस्य त्वयं भावः—बहिर्योग इति स्मर्यते। तेन परम्परया वास-संबद्धस्यापि सिद्धिरिति॥

(अनिष्टापत्तिपरिहारः)

(उपसंख्यानभाष्यवार्तिकम्)

अपुरीति वक्तव्यम्॥

(भाष्यम्)

इह मा भूत्—अन्तरायां पुरि वसति॥

(प्रदीपः) अपुरीति। गणसूत्र एतत् कर्तव्यम्, लिङ्ग-विशिष्टपरिभाषया ग्रहणप्रसङ्गात्। इह त्वनेन नार्थः, अत्र इति जसः शीविधानादावन्तात्प्राप्त्यभावात्। पूः कस्मिंश्चिद्देशे प्राकाराभ्यन्तरे क्रियते क्वचित्प्राकाराद्बहिरित्यस्ति पुरो बहि-र्योगः॥ ३६॥

(उद्योतः) ननु जसि विकल्पविधायकस्यास्य वार्तिकोदाहरणं सप्तम्यन्तमयुक्तमत आह—गणेति। पूःशब्दस्य विशेष्यत्वे-इत्यर्थः॥ स च स्त्रियामेव, तदाह—इह त्विति॥ ३६॥

(इष्टानुपपत्तिनिराकरणाधिकरणम्)

(२०६ पूर्वपक्षिण उपसंख्यानवार्तिकम्॥ १॥)

॥*॥ वाप्रकरणे तीयस्य ङित्सूप-संख्यानम्॥*॥

(भाष्यम्)

वाप्रकरणे तीयस्य ङित्सूपसंख्यानं कर्तव्यम्। द्वितीयायै-द्वितीयस्यै, तृतीयायै-तृतीयस्यै। "विभाषा द्वितीयातृतीयाभ्याम्" इत्येतन्न वक्तव्यं भवति॥

(आक्षेपभाष्यम्)

किं पुनरत्र ज्यायः?

(समाधानभाष्यम्)

उपसंख्यानमेवाऽत्र ज्यायः। इदमपि सिद्धं भव-ति—द्वितीयाय-द्वितीयस्मै, तृतीयाय-तृतीयस्मै॥३६॥

(इति सर्वनामसंज्ञाप्रकरणम्)

(अथाव्ययसंज्ञाप्रकरणम्)

(३१ अव्ययसंज्ञासूत्रम्॥ १।१।६ आ. ९॥)

स्वरादिनिपातमव्ययम्॥ १।१।३७॥

(उभयसंज्ञाप्रयोजनम्)

(आक्षेपभाष्यम्)

किमर्थं पृथग्ग्रहणं स्वरादीनां क्रियते, न चादि-ष्वेव पठ्येरन्?

(प्रदीपः) स्वरादिनिपातम०॥३७॥ किमर्थमिति। स्वरादिषु किंचित्क्रियाप्रधानं किंचित्साधनप्रधानमिति असत्त्व-वचनत्वाच्चादिष्वेव स्वरादीनि पठितव्यानीति मत्वा प्रश्नः॥

(उद्योतः) स्वरादि०॥ ३७॥ क्रियाप्रधानमिति। क्रियायामेवं विशेषणमित्यर्थः। यथा—हिरुगादि। एतच्चोत्तरसूत्रे कैयटे स्पष्टम्॥ किंचिदिति। यथा-उच्चैरादि॥

(समाधानभाष्यम्)

चादीनां वै असत्त्ववचनानां निपातसंज्ञा। स्व-रादीनां पुनः सत्त्ववचनानामसत्त्ववचनानां च॥

(प्रदीपः) स्वरादीनां पुनरिति। स्वरिति वाचयति स्वः पश्येति स्वरित्यस्यःशब्दे क्रियासम्बन्धेऽनेकशक्तिदर्शनात्सत्त्व-वाचित्वनिश्चयः। लोहितगङ्गमित्यादीनामव्ययानां सत्त्वधर्मन-पुंसकत्वदर्शनाच्चैकमेव सत्त्ववाचित्वम्॥

(उद्योतः) अनेकशक्तीति। 'स्वस्तिष्ठ' 'स्व आगतः' इत्या-दावित्यर्थः। अनेककारकशक्तियोग एव च सत्त्वमिति भावः॥ भाष्ये—असत्त्ववचनानां च इत्यस्याव्ययसंज्ञेष्यत इति शेषः॥ लोहितेति। अव्ययीभावश्चेति स्वरादिषु पठ्यते इति मते इदम्॥

(आक्षेपभाष्यम्)

अथ किमर्थमुभे संज्ञे क्रियेते, न निपातसंज्ञैव स्यात्॥

(प्रदीपः) न निपातसंज्ञैवेति। 'प्राग्रीश्वरान्नि-पाताः' 'स्वरादीनि' 'चादयोऽसत्त्वे' इति सूत्रन्यासः कार्य इत्यर्थः॥

(उद्योतः) नन्वसत्त्ववाचित्वाभावाच्चादिषु पाठाभावात् कथं निपातत्वमत आह—प्राग्रीति॥

(समाधानभाष्यम्)

नैवं शक्यम्। "निपात एकाजनाङ्" इति प्रगृह्य-संज्ञोक्ता, सा स्वरादीनामप्येकाचां प्रसज्येत॥

(प्रदीपः) स्वरादीनामिति। 'किमोऽत्' इत्यत्प्रत्ययो 'दक्षिणादाच्' इत्याच्। केन्प्रभृतयस्तु कृत एकाचः सन्तीति भावः॥

(उद्योतः) किमोदिति। तद्धितश्चेति सूत्रमपि तत्संज्ञा-विधायकमेव। एतत्प्रयोजनसत्त्वादेव केषांनामपि तेषां संज्ञा स्यादिति भावः॥

(आक्षेपभाष्यम्)

एवं तर्ह्यव्ययसंज्ञैव स्यात्॥

(उद्योतः) भाष्ये—एवं तर्ह्यव्ययेति। 'प्राग्रीश्वरा-दव्ययम्' 'स्वरादीनि' 'चादयोऽसत्त्वे' इति पाठमित्यर्थः॥

(समाधानभाष्यम्)

तच्चाशक्यम्। वक्ष्यत्येतत्—*अव्यये नञ्कुनि-पातानाम्*इति। तद्दरीयसा न्यासेन परिगणनं कर्तव्यं स्यात्। तस्मात् पृथक् ग्रहणं कर्तव्यम्।

उभे च संज्ञे कर्तव्ये ॥ ३७ ॥

(प्रदीपः) **तच्चावाक्यमिति** । अव्ययसंज्ञायामेव सत्यां 'अव्ययमेकाजनाङ्' इति सूत्रं कर्तव्यम्। ततश्चात्प्रभृतीनामपि प्रगृह्यसंज्ञाप्रसङ्गः प्राप्नोति । अथ **'चादय एकाजनाङ्'** इति क्रियते, तदा चादीनामसत्त्ववचनत्वं विशेषणमलभ्यम् ॥ ३७ ॥

(उद्योतः) तदा चादीनामिति । यदि तु 'चादयः', 'असत्त्वे' इति योगविभागेन 'असत्त्वे' इति पाठविशेषणं क्रियते तदा नायं दोषः । तस्माद्भाष्योक्त एव दोषः । न च तत्र प्रादीनामिति वाच्यम्, ऊर्यादीनामसंग्रहापत्तेः । एवं निपाता आद्युदात्ता इत्यादावपि दोषो बोध्यः ॥ ३७ ॥

(२४ अव्ययसंज्ञासूत्रम् ॥ १ । १ । ६ आ. १०)

तद्धितश्चासर्वविभक्तिः ॥ १।१।३८ ॥

(इष्टानुपपत्तिपरिहाराधिकरणम्)

(२०७ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ असर्वविभक्तावविभक्तिनिमित्तस्योपसंख्यानम् ॥ * ॥

(भाष्यम्)

असर्वविभक्तावविभक्तिनिमित्तस्योपसंख्यानं कर्तव्यम् । विना, नाना ॥

(प्रदीपः) **तद्धितश्चासर्वविभक्तिः ॥ ३८ ॥** इह **संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिप्रतिषेधाद्** यद्यपि केवलस्य प्रत्ययस्य ग्रहणं, तथापि **प्रयोजनं सर्वनामाव्ययसंज्ञायामिति** वाचनिकस्तदन्तविधिरस्तीति तदन्तस्याव्ययसंज्ञा विज्ञायते ॥ तत्र वृत्तिकारेण व्याख्यातम्—असर्वा विभक्तिर्यस्य सोऽसर्वविभक्तिरिति ॥ तत्र यदाऽयमर्थः—यस्य तद्धितस्याऽसर्वा विभक्तिः कार्या=यस्मान्न सर्वा विभक्तिरुत्पद्यते इत्यर्थस्तदा न दोषः । यदा तु यस्य तद्धितस्योत्पत्तौ निमित्तत्वेनासर्वा विभक्तिराश्रिता सोऽसर्वविभक्तिः, यथा 'सर्वैकान्य-' इति दाप्रत्ययस्य सप्तम्येवोत्पत्तिनिमित्तमिति । एतस्मिन् सूत्रार्थे विनानानेत्यव्ययसंज्ञा न सिध्यति । न हि 'विनञ्भ्याम्' इत्यत्र प्रतिनियता काचिद्विभक्तिराश्रितेत्याह—**असर्वविभक्ताविति** । अविद्यमानसिध्यास्मिन् सूत्रार्थे, दाक्षिरितीञः षष्ठ्येव निमित्तमिति संज्ञाप्रसङ्गात् ॥ **अविभक्तिनिमित्तस्येति** । अश्रूयमाणविभक्तिकमव्ययमविभक्तीत्युच्यते । तन्निमित्तस्य यस्येष्यते न च प्राप्नोति तस्योपसंख्यानं कर्तव्यं; न तु सामान्येनाविभक्तिनिमित्तस्य संज्ञा विधेया, विशालविशङ्कटादीनामपि प्रसङ्गात् ॥

(उद्योतः) **तद्धितश्चा० ॥ ३८ ॥ यद्यपि केवलस्येति** । एवं च केवलतद्धितात्कस्या अपि विभक्तेरभावेनासर्वविभक्तिरिति विशेषणमव्यावर्तकमिति भावः ॥ **वाचनिक इति** । शब्दरूपं विशेष्यमादाय तदन्तविधिरिति भावः ॥ किंच केवलानां संज्ञायां प्रयोजनाभावः, प्रयोजकाभावश्च । अन्यर्थसंज्ञालभ्योऽर्थो हि तत्प्रयोजक इति बोध्यम् ॥ वार्तिकोत्थानाय सूत्रार्थं दर्शयति—**तत्र वृत्तिकारेणेति** ॥ **सर्वा विभक्तिरिति** । सर्वावयविकेत्यर्थः ॥ **प्रतिनियतेति** । एवं च विशेषतः कस्या अपि निमित्तत्वेनानाश्रयणात्सर्वविभक्तिनिमित्तकोऽयमिति भावः ॥ ननु सुबन्तात्तद्धितोत्पत्तेरविभक्तिनिमित्तस्तद्धितोऽप्रसिद्धोऽत आह—**अश्रूयमाणेति** । 'तन्निमित्तस्य' इति बहुव्रीहिः ॥

(आक्षेपभाष्यम्)

किं पुनः कारणं न सिध्यति ?

(प्रदीपः) **किं पुनरिति** । 'एकवचनमुत्सर्गतः' इति वचनात् क्रमव्यतिक्रमे कारणाभावात् विनानानेत्यत्राप्यसर्वा विभक्तिरुत्पत्तौ निमित्तमिति **प्रश्नः** ॥

(उद्योतः) ननूत्सर्गत एकवचनमपि सर्वासां स्यादिति बहुवचनान्तविग्रहे सर्वविभक्तेर्निमित्तत्वमभ्याहतमत आह—**क्रमव्यतिक्रम इति** । प्रथमातिक्रमे कारणाभावेन प्रथमाया एवैकवचनमिति न दोष इत्यर्थः ॥

(२०८ आक्षेपहेतुवार्तिकम् ॥ २ ॥)

॥ * ॥ सर्वविभक्तिरविशेषात् ॥ * ॥

(भाष्यम्)

सर्वविभक्तिर्ह्येष भवति ॥

किं कारणम् ?

अविशेषेण विहितत्वात् ॥

(प्रदीपः) **सर्वविभक्तिरिति** । अविशेषेणोत्पद्यन्ते, उत्पन्नानां नियमः क्रियते-इत्यव्ययात् सर्वा विभक्तय उत्पद्यन्त इत्यर्थः ॥ **अविशेषादिति** । विशेषस्यानाश्रयणादिति भावः ॥

(उद्योतः) **अविशेषेणेति** । द्व्येकयोरित्याद्येकवाक्यतामनपेक्ष्येत्यर्थः ॥ **उत्पन्नानां नियम इति** । उत्पन्नानां शास्त्रबलान्नियमेन लोपेनेव निवृत्तिः क्रियत इत्यर्थः ॥ इदमप्यर्थनियमे सजातीयापेक्षप्रत्ययनियमे च बोध्यम् ॥ **विशेषस्येति** । द्व्येकयोरित्याद्येकवाक्यतारूपस्येत्यर्थः । ज्ञापकाद्विभक्तिरिति पक्षे 'इयमेव' इति विशेषस्येत्यर्थः ॥

(२०९ आक्षेपवार्तिकम् ॥ ३ ॥)

॥ * ॥ त्रलादीनां चोपसंख्यानम् ॥ * ॥

(भाष्यम्)

त्रलादीनां चोपसंख्यानं कर्तव्यम् । तत्र–यत्र, ततः–यतः ॥

(प्रदीपः) **त्रलादीनां चेति** । आदिशब्दस्य प्रकारवाचित्वात्तसिलपि गृह्यते ॥

(उद्योतः) ननु त्रलादीनामित्युक्त्वा त्रलः प्राक् पठितस्य तसिलः कथमुदाहरणदानमत आह—**आदिशब्दस्येति** ॥

(आक्षेपबाधकभाष्यम्)

ननु च विशेषे एते विधीयन्ते–"पञ्चम्यास्तसिल्" "सप्तम्यास्त्रल्" इति ॥

(आक्षेपसाधकभाष्यम्)

वक्ष्यत्येतत्—"इतराभ्योऽपि दृश्यन्ते" इति ॥

(प्रदीपः) **वक्ष्यत्येतदिति।** भवदादिप्रयोग एवाप्राप्तिश्चोद्यत इत्यर्थः ॥

—•—

(न्यासान्तरनिराकरणम्)

(न्यासान्तरभाष्यम्)

यदि पुनरविभक्तिश्शब्दोऽव्ययसंज्ञो भवतीत्युच्यते ॥

(प्रदीपः) **यदि पुनरिति।** प्रयोगे योऽश्रूयमाणविभक्तिः सोऽव्ययमित्यर्थः। न च दधिमध्वित्यत्रातिप्रसङ्गः, दध्नीत्यादौ विभक्तिश्रवणात् ॥

(उद्द्योतः) ननु 'विना' इत्यादावपि पदत्वाय विभक्त्युत्पत्तिरावश्यिकेत्यत आह—**प्रयोगे इति** ॥ **दध्नीत्यादाविति।** प्रयोगमात्रे विभक्त्यभावो विवक्षित इति भावः ॥

(२१० आक्षेपवार्तिकम् ॥ ४ ॥)

॥ * ॥ अविभक्तावितरेतराश्रयत्वादप्रसिद्धिः ॥ * ॥

(भाष्यम्)

अविभक्तावितरेतराश्रयत्वादप्रसिद्धिः संज्ञायाः।

का इतरेतराश्रयता ?

सत्यविभक्तित्वे संज्ञया भवितव्यं, संज्ञया चाविभक्तित्वं भाव्यते, तदितरेतराश्रयं भवति। इतरेतराश्रयाणि च न प्रकल्पन्ते ॥

(प्रदीपः) **अविभक्ताविति।** अव्ययत्वादविभक्तित्वम्, अविभक्तित्वादव्ययत्वमिति दोषः ॥

(उद्द्योतः) **अव्ययत्वादिति।** अविभक्तिकत्वस्य स्वाभाविकत्वेऽव्ययादाप्सुप इत्यस्य वैयर्थ्यप्रसङ्गादिति भावः ॥

(२११ न्यासान्तरवार्तिकम् ॥ ५ ॥)

॥ * ॥ अलिङ्गमसंख्यमिति वा ॥ * ॥

(भाष्यम्)

अथवाऽलिङ्गमसंख्यमव्ययसंज्ञं भवतीति वक्तव्यम् ॥

एवमपीतरेतराश्रयमेव ॥

का इतरेतराश्रयता ?

सत्यलिङ्गासंख्यत्वे संज्ञया भवितव्यम्। संज्ञया चालिङ्गासंख्यत्वं भाव्यते, तदेतदितरेतराश्रयं भवति। इतरेतराश्रयाणि च कार्याणि न प्रकल्पन्ते ॥

(प्रदीपः) **अलिङ्गमसङ्ख्यमिति।** अविभक्तिरव्ययमित्यस्य लक्षणस्य दूषितत्वात् अत्रापि तदेव दूषणमिति प्रदर्शनार्थो वाशब्दः। अलिङ्गासङ्ख्यत्वस्य लौकिकत्वान्नेतरेतराश्रयत्वमिति पूर्वपक्षः ॥ **एवमपीति।** अर्थमपि कश्चित् क्वचित् शास्त्रादेव प्रतिपद्यत इति भावः ॥

(उद्द्योतः) ननु पूर्वलक्षणस्य दूषितत्वाद्वाशब्दोऽसङ्गतोऽत आह—**अविभक्तिरिति** ॥ **वाशब्द इति।** प्रयुक्त इति शेषः ॥ एवंचाप्यर्थो वाशब्द इत्यर्थः ॥ **अलिङ्गमित्यपि** यद्युच्यते एवमपि अन्योन्याश्रय इत्यर्थः ॥ **शास्त्रादेवेति।** तद्द्योतकविभक्तिलुक्शास्त्रादेवेति भावः ॥

(दूषणपरिहारभाष्यम्)

नेदं वाचनिकम्—अलिङ्गता असंख्यता च।

किं तर्हि ?

स्वाभाविकमेतत्। तद्यथा समानमीहमानानां चाधीयानानां च केचिदर्थैर्युज्यन्ते, अपरे न। [तत्र किमस्माभिः कर्तुं शक्यम्। स्वाभाविकमेतत् ॥]

(आक्षेपभाष्यम्)

तर्हि वक्तव्यम्—अलिङ्गमसंख्यमिति ॥

(समाधानभाष्यम्)

न वक्तव्यम् ॥

(२१२ समाधानहेतुवार्तिकम् ॥ ६ ॥)

॥ * ॥ सिद्धं तु पाठात् ॥ * ॥

(भाष्यम्)

पाठाद्वा सिद्धमेतत् ॥

कथं पाठः कर्तव्यः ?

तसिलादयः प्राक् पाशपः। शस्प्रभृतयः प्राक् समासान्तेभ्यः। मान्तः। तसिवती। कृत्वोऽर्थः। नानाञाविति ॥

(प्रदीपः) **सिद्धं त्विति।** वार्तिककारस्येतरेतराश्रयदोषः स्थित एवेति तुशब्दो विशेषप्रदर्शनार्थः। भाष्यकारेण त्वितरेतराश्रयदोषः परिहृत इति वाशब्दार्थः-तुशब्दो व्याख्यातः ॥ य एव **प्रकारवचने थाल्** स एव **प्रज्ञादिभ्यो** विधीयते इति नाव्याप्तिः ॥ **मान्त इति।** अम् आम् ॥ **तसिः—'प्रतियोगे पञ्चम्यास्तसिः' 'तेनैकदिक् तसिश्च'** इति ॥ **कृत्वोऽर्थः**—कृत्वसुच्, सुच्, धा ॥

(उद्द्योतः) **वाशब्दार्थ इति।** वाशब्दस्यार्थ इवार्थो यस्य इति बहुव्रीहिः ॥ अयं च पाठः स्वरादिषु कार्य इति बोध्यम् ॥ स च पचतिकल्पादिव्यावृत्तये तद्धितश्चेति सूत्रारम्भेऽप्यावश्यक इति भावः ॥ प्रेत्येत्यादि थाल् न परिगणितमध्यवर्तीत्यत आह—**स एवेति।** प्रकारवचन इत्यत्र प्रकारः—सादृश्यं विशेषश्च। तत्र शब्दशक्तिमाहात्म्यात् प्रज्ञादिभ्य उत्पन्नेन सादृश्यमुच्यते, किमादिभ्यस्त्वाल तु विशेषः, एवं च प्रज्ञपूर्वेति सूत्रं व्यर्थमेव। लोकेऽप्रयोगस्त्वनभिधानादिति भावः ॥ अमु च छन्दसीत्यम् ॥ **किमेत्तिङिति आम्** ॥ **प्रतियोगे** इति तसिः शस्प्रभृतिष्वस्तीति तद्ग्रहणं चिन्त्यम्। दृष्टान्तार्थमित्यन्ये ॥ भाष्ये—**वतिः—तेन तुल्यमिति** विहितः। **न तूपसर्गाच्छन्दसीति** विहितः, उद्वतो निवत इत्यादौ तस्य लिङ्गसंख्याद्यन्वयदर्शनादित्याहुः ॥

(प्रथमन्यासाङ्गीकरणभाष्यम्)

अथवा पुनरस्तु—अविभक्तिश्शब्दोऽव्ययसंज्ञो भवतीत्येव ॥

(प्रदीपः) अथवेति । वृद्धव्यवहारादेव शब्दार्थसम्बन्धावगमादेकत्वादिव्यवहारवदलिङ्गासङ्ख्यत्वमप्यव्ययार्थस्य प्रसिद्धमित्यर्थः ॥

(उद्योतः) एकत्वादिव्यवहारवदिति । घटादिपदानामिति शेषः ॥ अलिङ्गासङ्ख्यत्वमपीति । तथा च संख्याभावादेव विभक्त्यनुत्पत्तिरिति अविभक्तिरिति न्यासोऽप्यदुष्ट इति भावः ॥ अव्ययादाप्सुप इति सूत्रं तु न्यायसिद्धाया अनुत्पत्तेरेवान्वाख्यापकं, प्रत्ययलक्षणप्रवृत्तिद्वारा पदत्वादिसंपादनार्थमिति तात्पर्यम् ॥

(आक्षेपस्मारणभाष्यम्)

ननु चोक्तम्—*अविभक्ताविततरेतराश्रयत्वादप्रसिद्धिः* इति ॥

(आक्षेपबाधकभाष्यम्)

नैष दोषः । इदं तावदयं प्रष्टव्यः—यद्यपि तावद्वैयाकरणा विभक्तिलोपमारभमाणा अविभक्तिकाञ्छब्दान्प्रयुञ्जते । ये त्वेते वैयाकरणेभ्योऽन्ये मनुष्याः कथं तेऽविभक्तिकाञ्छब्दान्प्रयुञ्जते ?

अभिज्ञाश्च पुनर्लौकिका एकत्वादीनामर्थानाम् ॥

आतश्चाभिज्ञाः । अन्येन हि वस्नेनैकं गां क्रीणन्ति, अन्येन द्वौ, अन्येन त्रीन् । अभिज्ञाश्च न च प्रयुञ्जते ।

तदेतदेवं संलक्ष्यताम्—अर्थरूपमेवैतदेवंजातीयकं येनात्र विभक्तिर्न भवतीति ॥

(उद्योतः) नन्ववैयाकरणैः संख्याया अज्ञानादेव तद्वाचकविभक्तिर्न प्रयुज्यत इत्यत आह—भाष्ये—अभिज्ञाश्चेति । घट इत्यादौ तैरपि एकवचनादिप्रयोगकरणादिति भावः ॥ युक्त्यन्तरमप्याह—आतश्चाभिज्ञा इति ॥ वस्नः=मूल्यम् ॥

(उपपत्तिभाष्यम्)

तच्चाप्येतदेवमनुगम्यमानं दृश्यताम् । किंचिदव्ययं विभक्त्यर्थप्रधानं, किंचित् क्रियाप्रधानम् । उच्चैर्नीचैरिति विभक्त्यर्थप्रधानम् । हिरुक् पृथगिति क्रियाप्रधानम् । तद्धितश्चापि कश्चिद् विभक्त्यर्थप्रधानः, कश्चित् क्रियाप्रधानः । तत्र यत्र-इति विभक्त्यर्थप्रधानः, विना नाना-इति क्रियाप्रधानः । न चैतयोरर्थयोर्लिङ्गसंख्याभ्यां योगोऽस्ति ॥

(प्रदीपः) अत्रैवोपपत्तिमाह—तच्चापीति ॥ किंचिदिति । अव्ययानां द्वैविध्यमेवेति प्रतिपाद्यते, अलिङ्गासङ्ख्यत्वप्रतिपादनाय ॥ अन्ये त्वाहुः—किंचिदव्ययं क्रियाप्रधानम्, किंचित्साधनप्रधानम् । अन्यत्तु नापि क्रियाप्रधानम्, नापि साधनप्रधानम् । यथा-'स्वः पश्य, लोहितगङ्गम्-उन्मत्तगङ्गं देशः' इति । तथा चात्र नपुंसकत्वमव्ययीभावश्चेत्यन्वाख्यायते । पूर्वं च भाष्यकारेणोक्तम्-स्वरादीनां पुनः सत्त्ववचनाना-मसत्त्ववचनानां चेति । तस्माद्बाहुल्याभिप्रायेणाऽलिङ्गमसङ्ख्यमव्ययमित्युच्यते । उच्चैर्नीचैरिति सप्तम्यर्थे वर्तते ॥ हिरुक् पृथगिति । क्रियाविशेषणत्वादेषां क्रियाप्राधान्यम् । क्रियापदप्रयोगमन्तरेणापि 'पृथक् देवदत्तः' इत्यादिप्रयोगः क्रियाक्षेपादुपपद्यते ॥ शब्दशक्तिस्वाभाव्याच्चैकस्मिन्नर्थे विधीयमानयोः 'तेनैकदिक्' 'तसिश्च' इत्यण्तसोर्भिन्नधर्मत्वम् । तत्र 'पैलुमूलम्' इति द्रव्यं प्राधान्येनाभिधीयते । 'पीलुमूलतः' इति तु द्रव्योपसर्जनस्तृतीयार्थ इति तस्य साधनप्रधानता ॥

(उद्योतः) अत्रैवेति । अलिङ्गासंख्यत्व एवेत्यर्थः ॥ उपपत्तिः—युक्तिः क्रियाप्रधानत्वादिरूपा । एवमनुगम्यमानमित्यस्योपपाद्यमानमित्यर्थः ॥ नापि साधनप्रधानमिति । किं तु द्रव्यप्रधानमिति शेषः ॥ तस्माद्बाहुल्येति । एवं च तादृशबहुमध्यपाठेन स्वरादीनामप्यलिङ्गासंख्यत्वमनुमीयते । अनेककारकशक्तियोगमात्रेण तु सत्त्ववचनत्वमिति भावः ॥ उन्मत्तगङ्गादीनां वाचनिकमव्ययत्वमव्ययीभाव इति महासंज्ञया सूच्यते ॥ सत्त्वप्रधानता तु 'इदं स्वर्' इति सर्वनाम्ना परामर्शात्। ग्लान्याद्यर्थकं 'प्रताम्' इत्याद्यपि सत्त्ववचनमित्यन्ये ॥ ननु तदर्थे कारकान्वयाभावान्न तस्य क्रियात्वमत आह—क्रियाविशेषणत्वादिति । क्रियायामेव विशेषणत्वादित्यर्थः ॥ क्त्वान्ततुमुन्नन्तादिवदिति भावः ॥ स्वरादीनां घटादीनां च स्वःपतिर्घटोदकमित्यादौ नामार्थेऽप्यन्वयः ॥ एतेन तेषामपि क्रियाविशेषणत्वात्क्रियाप्राधान्यं दुर्वारमित्यपास्तम् ॥ अत एवैतदर्थे न कारकाणामन्वयः । तदन्वययोग्यस्य साध्यत्वरूपक्रियात्वस्य तत्राभावात् ॥ क्रियाक्षेपादिति । स्थित्यादिक्रियाक्षेपादित्यर्थः ॥ द्रव्यं प्राधान्येनेति । पीलुमूलसमानदिक्स्थमिति हि तत्र बोधः ॥ द्रव्योपसर्जन इति । तसिप्रत्ययाभिधेयद्रव्योपसर्जनः प्रकृत्यभिधेयस्तृतीयार्थ इत्यर्थः ॥ तृतीयार्थश्च तत्र साहित्यम् । पीलुमूलेनैकदिक्—पीलुमूलतः । एकदिक्सपीलुमूलसाहित्यमित्यर्थः ॥ अन्ये तु—पीलुमूलेन समानदिशीत्यर्थकम्—अधिकरणशक्तिप्रधानं पीलुमूलत इतीत्याहुः ॥ भाष्ये—न चैतयोरर्थयोरिति । यद्यपि क्रियायामेकत्वसंख्या रूपप्सूत्रे भाष्ये उक्ता, पचतिरूपमित्यादिवाच्यायाश्च नपुंसकत्वयोग उक्तः, तथापि अव्ययवाच्ययोरेतयोर्लिङ्गसंख्याभ्यामयोग इत्यर्थान्न दोष इति दिक् ॥

(सूत्रसमर्थनभाष्यम्)

अथाऽप्यसर्वविभक्तिरित्युच्यते । एवमपि न दोषः ।

कथम् ?

इदं चाऽप्यव्ययत्वे अतिबहु क्रियते—एकस्मिन्नेकवचनम्, द्वयोर्द्विवचनम्, बहुषु बहुवचनमिति ।

कथं तर्हि ?

एकवचनमुत्सर्गः करिष्यते । तस्य द्विबह्वोरर्थयोर्द्विवचनबहुवचने बाधके भविष्यतः ॥

(प्रदीपः) अद्यत्व इति । सूत्रारम्भकाल इत्यर्थः । पूर्वं हि न्यासान्तराश्रयेण सूत्रं प्रत्याख्यातम् ॥ अतिवह्विति । एकस्मिन्नित्यपनीय 'एकवचनम्' सूत्रं इति कर्तव्यम् । ततः 'द्विबह्वोर्द्विवचनबहुवचने' इत्येवं कर्तव्यम् । तेन द्वित्वबहुत्वयोर्द्विवचनबहुवचने भविष्यतः । एकवचनं त्वेकस्मिन्नपि भविष्यति, अलिङ्गासङ्ख्येभ्योऽव्ययेभ्यश्च ॥ ननु 'कर्मणि द्वितीया' इत्यादिना कर्मादिषु द्वितीयादीनां नियतत्वात्कथमेकवचनमव्ययेभ्यः स्यात् ॥ नैष दोषः । एतदर्थमेव 'एकवचनम्' इत्येतत् क्रियतेऽप्राप्तप्रापणार्थम् । तेन कर्माद्यभावेऽपि भवति । द्वित्वबहुत्वयोस्तु प्राप्तं द्विवचनबहुवचनाभ्यां बाध्यते ॥

(उद्द्योतः) सूत्रारम्भकाले इति । यद्यपि न्यासान्तरेऽपि एकस्मिन्निति वह्वेव, तथापि एकग्रहणे सति ज्ञापकादितः सर्वविभक्त्युत्पत्त्यावस्य सूत्रस्याप्यानर्थक्यमिति एतत्सूत्रपाठकाले एतत्सूत्रसहितं एकस्मिन्नित्यतिबहु व्यर्थं क्रियत इति एकग्रहणं त्यक्त्वाऽस्य सार्थक्यं वक्तुं योग्यमित्यर्थ इति भावः ॥ न्यासान्तरेति । पाठाश्रयेणालिङ्गासंख्यमित्यनेन वेत्यर्थः ॥ भाष्ये—अतिवह्विति बहुशब्दो वैपुल्यवाची । अतिबहु शास्त्रं व्यर्थं क्रियत इत्यर्थः ॥ अलिङ्गासंख्येभ्य इति । द्विवचनबहुवचनविधायकयोर्द्विबहुग्रहणसामर्थ्यान्महासंज्ञाबोध्यैकत्वाभावेऽपि एकवचनप्रवृत्तिरिति भावः ॥ कथमेकवचनमिति । प्रथमाऽपि मात्रग्रहणात् यत्प्रातिपदिकार्थस्य कर्मत्वाद्याधिक्यसंभावना तत्रैवेति भावः ॥ अप्राप्तेति । द्वित्वबहुत्वयोर्द्विवचनबहुवचनविधाने एकवचनस्यार्थाच्चदभावे कर्मादौ सिद्धत्वेन सामर्थ्यादिति भावः । अप्राप्तिश्च कर्मत्वाद्यभावप्रयुक्तैव न तु प्रातिपदिकत्वाभावप्रयुक्ताऽपि, सुब्विध्येकवाक्यत्वात् । तेन तिङन्तादिभ्यो नापत्तिरिति बोध्यम् ॥ किं च सर्वथाऽप्राप्तावेवास्य विधायकत्वमिति पचतिकल्पमित्यादौ न सर्वैकवचनापत्तिरिति बोध्यम् ॥ यद्यप्यनिर्दिष्टार्थत्वात्स्वार्थे विधीयमानस्यास्य न द्वित्वादौ प्राप्तिस्तथापि पञ्चकप्रातिपदिकार्थपक्षे एकत्व इव द्वित्वादावपि प्राप्तिरित्याशयेनाह—बाध्यत इति । अत्र पक्षे द्व्येकयोरिति सूत्रमपि विध्यर्थमेवेति भावः ॥ यद्यपि अव्ययात्सर्वविभक्त्युत्पत्त्याऽयं न्यासो दूषितः, तथापि सामान्यापेक्षप्रत्ययनियमे एकवाक्यतया विधाने वा कस्या अप्यप्राप्त्येदं विधायकमिति तत्पक्षे सूत्रसार्थक्योपपादनमिदम् । एवं चैतदेव तयोरन्यतरपक्षाश्रयणस्यैकपदे वाक्यार्थानन्वयित्वस्य च ज्ञापकमिति बोध्यम् । एतत्सर्वमुत्सर्गपदेन भाष्ये सूचितम् ॥

(मतान्तरभाष्यम्)

न चाप्येवं विग्रहः करिष्यते—न सर्वाः-असर्वाः, असर्वा विभक्तयो यस्मादिति ॥

कथं तर्हि ?

न सर्वा असर्वा, असर्वा विभक्तिरस्मादिति । त्रिकं पुनर्विभक्तिसंज्ञम् ॥

(प्रदीपः) न सर्वा विभक्तय उत्पत्तौ निमित्तमस्य-इति येन वृत्तिकारेण व्याख्यातं तन्मतं दूषितम् ॥ इदानीं वृत्तिकारान्तरमतं विशेषदर्शनेन संस्क्रियते—न चाप्येवमिति । एवं विग्रहे सर्वशब्दस्य प्रकारकार्त्स्न्येऽपि वर्तनादेकवचनमात्रोत्पत्तावपि सर्वा विभक्तयः सप्त-अव्ययेभ्य उत्पद्यन्ते इति न स्यादसर्वविभक्तित्वम् ॥ कथं तर्हीति । द्रव्यकार्त्स्न्येवृत्तिः सर्वशब्दः । एकवचनमात्रोत्पत्तौ निरवशेषा विभक्तिर्नोत्पन्ना भवतीति भवत्येवाऽसर्वविभक्तित्वम् ॥ यदा त्वयं न्यायः—प्रथमातिक्रमे कारणाभावात्प्रथमाया एवैकवचनमव्ययेभ्य उत्पद्यत इति, तदाऽसर्वा विभक्तयो यस्मादित्यपि विग्रहे आश्रिते न दोषः ॥ यदा तु खले कपोतिकान्यायेन सर्वैकवचनोत्पत्तिपक्षस्तदैतदुक्तम् । अव्ययीभावादप्येकवचनमेवोत्पद्यते, तावतैव 'तृतीयासप्तम्योर्बहुलम्' इत्यस्योपपादनात् ॥

( ) तन्मतमिति । दाक्षिरित्यादावतिव्याप्तिरितरेभ्योऽपि दृश्यन्त इत्येतद्विहितत्रलादिविषयेऽव्याप्तिश्चेति भावः ॥ वृत्तिकारान्तरेति । तद्विग्रहे यस्येति अपादानस्यैव संबन्धत्वविवक्षया षष्ठीति ध्वनयितुं भाष्ये—यस्मादित्युक्तम् ॥ विशेषेति । एकवचनान्तविग्रहकरणरूपो विशेषः ॥ नन्वेवं सर्वविभक्त्येकवचनोत्पत्तौ बहुवचनान्तविग्रहासङ्गतिरतो भाष्ये—न चापीति ॥ तद्व्याचष्टे—प्रकारेति । 'सर्वा विभक्तयः' इत्यस्य सर्वप्रकारा इत्यर्थः ॥ [2]अवयवकार्त्स्न्ये तु बहुवचनं व्यर्थमिति भावः ॥ [3]एकवचनान्तविग्रहे तु अवयवकार्त्स्न्ये एव सर्वशब्द इति 'नाना' इत्यादौ नाव्याप्तिः, नापि दाक्षिरित्यादावतिव्याप्तिरिति भावः ॥ भावे पचतिकल्पमित्यादौ च क्रियायाः स्वत एवैकत्वादेकवचनमेव ॥ तच्च भावे प्रथमपुरुषस्यैव, लान्तसमानाधिकरणयुष्मदाद्यभावादिति रूपप्सूत्रे भाष्ये स्पष्टम् ॥ अव्ययेभ्योऽपि प्रथमैकवचनमेवास्तु इत्याह—यदा त्विति ॥ प्रथमेति । अनेकनियमबाधे गौरवाच्चेत्यपि बोध्यम् ॥ ननु भाष्योक्तपक्षेऽव्ययेभ्यो युगपत्सर्वविभक्त्येकवचनानां कर्तुमशक्यत्वम्, परश्चेत्युक्तेः । किंतु यत्किञ्चिदेव, लुकि तस्य तावतैव पदत्वसंपादनात् विभक्त्यन्तरोत्पत्तौ मानाभावेन बहुवचनान्तविग्रहेऽपि न दोषोऽत आह—खले कपोतेति ॥ वाचः क्रमवृत्तित्वाद्युगपदुच्चारणासंभवेऽपि बुद्ध्या युगपत्सर्वोत्पत्तिर्वक्तुं शक्येति भावः ॥ विनिगमनाविरहोऽत्र बीजम् । प्रक्रियादशायां च बुद्धिरेव मुख्या, असाधूच्चारणायोगात् । यद्वा-प्रधानानुरोधेन गुणावृत्तेस्तावत्यः प्रकृतयः स्युरिति भावः ॥ परे तु प्राथम्यं स्वादिसूत्रे प्रथमायाः, नियमशास्त्रपर्यालोचनया द्वितीयाया इति न तन्नियामकमिति 'प्रथमातिक्रमे' इत्याद्यसङ्गतम् । तन्न्यायाश्रयणे निजां त्रयाणामित्यत्र त्रयाणामित्यस्य, आद्युदात्तश्चेत्यादावादिग्रहणस्य वैयर्थ्यं चेत्याहुः ॥ तावतैवेति । टाङ्योरिति वक्तव्ये तृतीयादिग्रहणं तु वैचित्र्यार्थमिति भावः ॥

(लाघवभाष्यम्)

'एवंगते कृत्यपि तुल्यमेत-
न्मान्तस्य कार्यं ग्रहणं न तत्र ।
ततः परे चाभिमता न कार्या-
स्त्रयः कृदर्था ग्रहणेन योगाः' ॥ १ ॥

(प्रदीपः) एवं गत इति । यदा असर्वा विभक्तिरस्मादिति विग्रह आश्रीयते, तदैवं विज्ञाते सत्येतावल्लक्षणमस्तु—'असर्वविभक्त्यव्ययम्' इति । पञ्चसूत्री न कर्तव्या । एतद्-

सर्वविभक्तित्वं कृत्यपि तुल्यम्—यस्य कृन्मेजन्त इत्यनेनाव्ययसंज्ञेष्यते ॥ मान्तस्येति । सूत्रोपलक्षणम् ॥ ततः पर इति । कृन्मेजन्त इत्यस्मात् सूत्रात्परे कृदर्थाः-कृत्संज्ञाविषयाः क्त्वातोसुन्कसुन इत्यर्थः ॥ ग्रहणेन—उच्चारणेन, प्रतिपदमित्यर्थः ॥ योगाश्च न कर्तव्याः स्वरादिनिपातमव्ययमित्येवमादयः पञ्चेत्युपसंहारः ॥

(उद्द्योतः) इदमेव ध्वनयितुं पञ्चयोगान्प्रत्याचष्टे—एवं गते इति—भाष्ये ॥ प्रतिपदमितीति । असर्वविभक्तीति न्यासेनैव सिद्धत्वादित्यर्थः ॥ भाष्यश्लोके—तत्रेति । अव्ययसंज्ञाविधावित्यर्थः ॥ पञ्चेति । स्वरादीत्यादिरव्ययीभावश्चेत्यन्ताः ॥

(गौरवप्रदर्शकभाष्यम्)

'कृत्तद्धितानां ग्रहणं तु कार्यं
संख्याविशेषं ह्यभिनिश्रिता ये ।'

तेषां प्रतिषेधो भवतीति वक्तव्यम् । इह मा भूत्—एको द्वौ बहव इति ॥

(उपसंहारभाष्यम्)

'तस्मात् स्वरादिग्रहणं च कार्यं
कृत्तद्धितानां ग्रहणं च पाठे' ॥ २ ॥

(प्रदीपः) इदानीमतिव्याप्तिपरिहारार्थं तद्धितग्रहणं कर्तव्यम्, तस्मिन् कृते कृन्मेजन्त इत्याद्यपि कर्तव्यमिति दर्शयति—कृत्तद्धितानामिति ॥ संख्याविशेषमिति । तन्निवृत्त्यर्थमित्यर्थः ॥ तेषामिति । असति तद्धितग्रहणे एकादीनामप्यसर्वविभक्तित्वात् प्रतिषेधो वक्तव्यः स्यादिति तद्धितग्रहणं कर्तव्यम् । तस्मिन्कृते स्वरादिग्रहणं कर्तव्यं, स्वरादीनामतद्धितान्तत्वात् ॥ ननूभयशब्दस्य द्विवचनानुत्पादादसर्वविभक्तित्वं, तथा गोदौ वरणा इति, तत एषामपि तद्धितश्चासर्वविभक्तिरित्यव्ययसंज्ञाप्रसङ्ग इत्याह—कृत्तद्धितानामिति । प्रतिपदं तद्धिताः पठितव्याः, येषामव्ययसंज्ञेष्यत इत्यर्थः । तस्माद्गणपाठ एवाश्रयितव्यः । प्रपञ्चार्थस्तु सूत्रारम्भः ॥

(उद्द्योतः) 'ये' इति यच्छब्दस्य तच्छब्दसाकाङ्क्षत्वादाह—तन्निवृत्त्यर्थमिति । तदेवं सूत्रं स्थापितमिति वार्तिकोक्तं सिद्धं तु पाठादित्यप्यनाश्रितं स्यात् । एवं चोभयशब्दादौ दोष इति शङ्कोत्तरत्वेनोत्तरभाष्यमवतारयति—ननूभयेति । अतै एवोभयोऽन्यत्रेत्यस्योदाहरणं—उभये-उभया इति भाष्ये सर्वादिसूत्रे दत्तम् । गोदावित्यादौ वरणादिभ्यश्चेति चातुरर्थिकलुपि युक्तवद्भावात्प्रत्ययार्थस्य द्वित्वादीति बोध्यम् ॥ इत्याहेति । इत्याशङ्कायामाहेत्यर्थः ॥ भाष्ये—चस्त्वर्थे । कृत्तद्धितानामित्यत्र कृद्ग्रहणेन क्त्वामव्ययसंज्ञाविधायके सूत्रेऽपि गणे पाठ्ये इति सूचितम् ॥ कृदित्युपलक्षणमव्ययीभावश्चेत्यस्यापि । तदाह—तस्मादिति ॥ तदेवं गणपाठमाश्रित्य तद्धितश्चासर्वविभक्तिरित्यष्टाध्यायीपाठः प्रत्याख्यातः । तदाह—प्रपञ्चार्थस्त्विति ॥

(आक्षेपभाष्यम्)

पाठेनेयमव्ययसंज्ञा कृता, सेह न प्राप्नोति—परमोच्चैः परमनीचैरिति ॥

(उद्द्योतः) शङ्कते—भाष्ये-पाठेनेयमिति । स्वरादिनिपातमितीत्यर्थः ॥

(समाधानभाष्यम्)

तदन्तविधिना भविष्यति ॥

(प्रदीपः) तदन्तविधिनेति । *प्रयोजनं सर्वनामाव्ययसंज्ञायाम्* इति वचनेनेति भावः ॥

(आक्षेपभाष्यम्)

इहापि तर्हि प्राप्नोति—अत्युच्चैः, अत्युच्चैसौ, अत्युच्चैस इति ॥

(प्रदीपः) इत्युच्चैसाविति । शक्तिप्रधानान्यप्यव्ययानि वृत्तिविषये शक्तिमत्प्रधानानि भवन्ति । यथा—दोषामन्यमहः, दोषाभूतमहरिति । तत उच्चैःशब्दस्य प्रक्रियायां द्वितीयान्तस्य समासः ॥

(उद्द्योतः) नन्वत्याद्यो द्वितीययेत्युक्तेः कथमुच्चैःशब्देनाधिकरणशक्तिप्रधानेनाद्वितीयान्तेन समास इत्यत आह—शक्तीति ॥ द्वितीयान्तस्येति । अतिक्रान्तार्थान्वययोग्यकर्मद्वितीयान्तस्येत्यर्थः ॥ दोषामन्यमित्यत्र कर्मणीत्यधिकारे आत्ममाने खश् । दिनं रात्रिं मन्यत इत्यर्थः ॥

(आक्षेपबाधकभाष्यम्)

उपसर्जनस्य नेति प्रतिषेधो भविष्यति ॥

(आक्षेपभाष्यम्)

स तर्हि प्रतिषेधो वक्तव्यः ॥

(आक्षेपभाष्यम्)

न वक्तव्यः । सर्वनामसंज्ञायां प्रकृतः प्रतिषेध इहानुवर्तिष्यते ॥

(आक्षेपसाधकभाष्यम्)

स वै तत्र प्रत्याख्यायते ॥

(समाधानभाष्यम्)

यथा स तत्र प्रत्याख्यायते, इहापि तथा शक्यः प्रत्याख्यातुम् ॥

(अनुयोगभाष्यम्)

कथं च स तत्र प्रत्याख्यायते ?

(समाधानभाष्यम्)

महतीयं संज्ञा क्रियत इति ॥ इयमपि च महती संज्ञा क्रियते । संज्ञा च नाम यतो न लघीयः ॥ कुत एतत् ?

लघ्वर्थं हि संज्ञाकरणम् । तत्र महत्याः संज्ञायाः करण एतत्प्रयोजनम्—अन्वर्थसंज्ञा यथा विज्ञायेत—न व्येतीत्यव्ययमिति ॥

(अनुयोगभाष्यम्)

क्व पुनर्न व्येति ?

(प्रदीपः) **क्व पुनरिति** । श्लोके सप्तमीनिर्देशात् प्रश्नेऽपि सप्तमी निर्दिष्टा ॥

(उद्द्योतः) प्रश्नेऽपीति । 'व्येति' इत्यस्य विविधं प्रकारं गच्छतीत्यर्थः । 'क्व' इत्यस्य किंविषये-इत्यर्थ इति भावः ॥ अन्यथोत्तरानुसारेण 'कान्' इति प्रश्न उचितः । अत एवाग्रे उक्तम्—एतानर्थान् केचिद्वियन्तीत्यादि । विपूर्वस्येणो रूपम् ॥

(समाधानभाष्यम्)

स्त्रीपुन्नपुंसकानि सत्त्वगुणाः, एकत्वद्वित्वबहुत्वानि च । एतानर्थान् केचिद्वियन्ति केचिन्न वियन्ति । ये न वियन्ति तदव्ययम् ॥

"सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु ।
वचनेषु च सर्वेषु यन्न व्येति तदव्ययम्" ॥ १ ॥
तद्धितश्चासर्वविभक्तिः ॥ ३८ ॥

(प्रदीपः) **सदृशमिति** । लिङ्गविशेषप्रतिपादने सामर्थ्याभावात् ॥ **विभक्तिष्विति** । कारकेषु । तत्र यानि साधनप्रधानान्यव्ययानि तेषां शक्त्यन्तरानावेशात् क्रियाप्रधानानां च शक्तिसंबन्धाभावात्—**सर्वासु च विभक्तिषु-इत्युक्तम्** ॥ **वचनेष्विति** । एकत्वादिषु । अव्ययीभावस्य शक्तिलिङ्गविशेषयोगेऽपि वचनादव्ययत्वम् । यथा—स्वत्यादीनां कर्मप्रवचनीयसंज्ञा । तत्र यान्यसत्त्वभूतार्थाभिधायीन्यव्ययानि तेषां लिङ्गादिभिरयोगः, तेषां द्रव्यधर्मत्वात् । सत्त्ववाचिनामपि शब्दशक्तिस्वाभाव्यात्तदयोगः । यथा—युष्मदस्मदोर्लिङ्गायोगः ॥ **केचित्तु** लिङ्गादिविशेषेणायोगात् तत्सामान्येन तु योगमव्ययाना**माहुः** ॥ तदयुक्तम् । लिङ्गादिसामान्यसद्भावे प्रमाणाभावात् ॥ **यन्नव्येतीति** । नानात्वं न गच्छति, सत्त्वधर्मान्न गृह्णातीत्यर्थः ॥ ३८ ॥

(उद्द्योतः) **ये न वियन्ति**—एतानर्थान् येऽर्था न वियन्ति—विविधप्रकारप्रापकान्न प्राप्नुवन्ति तत्—तद्वाचकमव्ययमित्यर्थः । द्वित्वादेरर्थधर्मत्वादिति बोध्यम् ॥ ननु विभक्तिवचनशब्दयोः प्रत्ययपरत्वेऽन्यतरवैयर्थ्यमत आह—**कारकेष्विति** । विषयसप्तम्य एताः ॥ सादृश्यं तत्तल्लिङ्गाद्यभावानुयोगित्वेन ॥ नन्वेवं स्वरादिवाच्यानां कर्मत्वादियोगसत्त्वेन सकलकारकविषये न कारकाभावानुयोगित्वरूपं सादृश्यमत आह—**तत्र यानीति** ॥ साधनं—शक्तिः । तादृशान्युच्चैरादीनि ॥ तेषु चै कारकशक्त्यन्तरायोगात्सर्वकारकविषये कारकाभावानुयोगित्वमस्त्येवेत्यर्थः ॥ शक्तिः—कर्मत्वादिः ॥ वचनादिति । **अव्ययीभावश्चेति** वचनादित्यर्थः । **सङ्ख्याभावादिति** वाऽर्थः । 'मशकार्थः' इत्यादौ अभावस्य फलत्ववत् अत्र तदभावस्य कारणत्वमिति बोध्यम् ॥ **यथेति** । क्रियाहेतुकसंबन्धविशेषद्योतका हि अन्वर्थबलात्कर्मप्रवचनीयाः । स्वत्योस्तत्त्वाभावेऽपि क्रियापदसंनिधौ क्रियागतविशेषद्योतकयोरपि यथा संज्ञा, तथा प्रकृतेऽव्ययीभावादीनामित्यर्थः ॥ **सत्त्ववाचिनामपीति** । स्वरादीनामिति शेषः ॥ तदयोगः—लिङ्गसङ्ख्याऽयोग इत्यर्थः ॥ सदृशमित्यत्रोक्तं सादृश्यं निरूपयितुम्—**यन्नव्येतीत्यादि** । अत्रापि लिङ्गेष्वित्याद्यावृत्त्या संबध्यते ॥ **नानात्वमिति** । एतेषु यन्न व्येति—एतद्विषये यन्नानात्वं न प्राप्नोति तदव्ययमित्यर्थः ॥ क्वचित्तु **नाना न गच्छतीति** पाठः, तदा एतद्विषयमनेकप्रकारं न प्राप्नोतीत्यर्थः ॥ ३८ ॥

(३५ अव्ययसंज्ञासूत्रम् ॥ १ । १ । ६ आ. ११)

कृन्मेजन्तः ॥ १ । १ । ३९ ॥

(अन्वयाधिकरणम्)

(आक्षेपभाष्यम्)

कथमिदं विज्ञायते—कृद्यो मकारान्त इति, आहोस्वित्—कृदन्तं यत् मकारान्तमिति ।

किं चातः ?

यदि विज्ञायते—कृद्यो मान्त इति, 'कारयांचकार-हारयांचकार' इत्यत्र न प्राप्नोति ॥

अथ विज्ञायते—कृदन्तं यन्मान्तमिति, 'प्रतामौ प्रतामः' अत्रापि प्राप्नोति ॥

(प्रदीपः) **कृन्मेजन्तः ॥ ३९ ॥ कथमिति** । किं मेजन्तग्रहणेन पूर्वं कृद्विशेष्यते, पश्चात्तु कृता तदन्तविधिः । आहोस्वित्पूर्वं कृता तदन्तविधिः, पश्चात्तु कृदन्तं मेजन्तग्रहणेन विशेष्यत इति प्रश्नः ॥ **प्रयोजनं सर्वनामाव्ययसंज्ञायामिति** चात्र तदन्तविधिः ॥ अथवाऽन्वर्थसंज्ञाश्रयणात्प्रत्ययग्रहणे संज्ञाविधावप्यत्र तदन्तविधिर्भवति । न हि केवलस्य प्रत्ययस्याप्रयोगार्हस्य नानागमनमगमनं वा संभवति ॥ **कारयांचकारेति** । लिडत्र कृत्, स च मान्तो न भवति ॥ **प्रतामाविति** । क्विपि लुप्ते प्रत्ययलक्षणेन कृदन्तमेतद्भवति । श्रुत्या च मान्तम् ॥

(उद्द्योतः) **कृन्मेजन्तः ॥३९॥ किं मेजन्तेति** । कृतो मेजन्तस्य प्रत्ययमात्रस्य संज्ञा, उत कृदन्तस्येति न शङ्काऽर्थः । **प्रयोजनं सर्वनामाव्ययसंज्ञायामिति** तदन्तविधेरित्याशयः ॥ **पश्चात्त्विति** । मेजन्तो यः कृदन्तमव्ययमित्यर्थ इति भावः ॥ संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिनिषेधादाह—**प्रयोजनमिति** ॥ ननु तद्वचनमप्रत्ययांशे चरितार्थमत आह—**अथवाऽन्वर्थेति** । एवं चाव्ययत्वप्रयोजकस्य महासंज्ञालब्धार्थस्य केवलप्रत्ययेष्वभावात्तदन्तविधिरिति भावः ॥ अनयैव रीत्या सर्वादिगणे उतरडतमाभ्यां तदन्तविधिर्बोध्यः ॥ नानागमनमेवागमनमपि न संभवति, संभावितप्रतियोनिदेश एव तदभावबुद्धेः शब्देन जननात् । संभावितप्रतियोगितावच्छेदक एव 'अब्राह्मणः' इत्यादिना भेदबुद्धिवदित्याशयः ॥ **लिडत्र कृदिति** । तिङ्भावित्वाभावेनातिङिति न कृत्त्वप्रतिषेध इति भावः ॥ **प्रतामाविति** । तमः क्विप् । **अनुनासिकस्येति** दीर्घः ॥ **श्रुत्या चेति** । तथा चाव्ययत्वाल्लुक् स्यादिति भावः ॥

(समाधानभाष्यम्)

यथेच्छसि तथास्तु ॥ अस्तु तावत्—कृद्यो मान्त इति ॥

(आक्षेपभाष्यम्)

कथं कारयांचकार हारयांचकारेति ?

(प्रत्याक्षेपभाष्यम्)

किं पुनरत्राव्ययसंज्ञया प्रार्थ्यते ?

(प्रत्याक्षेपसमाधानभाष्यम्)

"अव्ययात्" इति लुग् यथा स्यात् ॥

(प्रदीपः) **अव्ययादिति लुगिति** । ननु हल्ङ्यादि-

लोपेन सिद्धत्वात् किं लुका प्रयोजनम् । यदा तर्ह्यनुप्रयोगवशात् द्वित्वबहुत्वावगतिः, तदाऽस्ति द्विवचनबहुवचनोत्पत्तिरिति लुगेषितव्यः । अकच् तु न भवति, अपरिसमाप्तार्थत्वादज्ञानादिभिर्योगाभावात् ॥

(उद्द्योतः) द्विवचनेत्यादि । ननु सङ्ख्याया अनुप्रयुज्यमानोत्तरलिङ्गेनाभिव्यक्तत्वात्कथं द्विवचनादिप्रसङ्ग इति चेत् । उपलक्षणमिदम् । सर्वैकवचनोत्पत्तिपक्षेऽमादिलुगर्थमिदमावश्यकमिति न दोषः । अव्ययात् सुपो लुगिति ज्ञापकात्सर्वविभक्तिरिति पक्षे च ॥ अकजर्थं तर्ह्यामन्तस्याव्ययत्वमेष्टव्यमत आह—अकच्त्विति । अपरिसमाप्तार्थत्वं च सङ्ख्याकारकादिविषयकोत्थिताकाङ्क्षत्वम् । अत एवानुप्रयोगः प्रार्थ्यते । स्वार्थे परिपूर्णस्यैव चार्थान्तरेण संबन्ध इति भावः ॥

(समाधानबाधकभाष्यम्)

मा भूदेवम् । "आमः" इत्येवं भविष्यति ॥

(समाधानसाधकभाष्यम्)

न सिध्यति । लिग्रहणं तत्रानुवर्तते ॥

(समाधानबाधकभाष्यम्)

लिग्रहणं निवर्तिष्यते ॥

(समाधानसाधकभाष्यम्)

यदि निवर्तते, प्रत्ययमात्रस्य लुक् प्राप्नोति ॥

(समाधानबाधकभाष्यम्)

इष्यते च प्रत्ययमात्रस्य । आतश्चेष्यते । एवं ह्याह—"कृञ्चानुप्रयुज्यते लिटि" इति । यदि च प्रत्ययमात्रस्य लुग्भवति तत एतदुपपन्नं भवति ॥

(प्रदीपः) इष्यते चेति । पूर्वोक्ताद्धेतोस्तरबाद्यनुत्पादादनुप्रयोग एव तरबाद्युत्पत्तिः, समासार्थस्य प्रकर्षादियोगादित्यर्थः ॥ अत्रैवार्थे ज्ञापकमाह—आतश्चेति । तत्र ह्युक्तं—व्यवहितनिवृत्त्यर्थं चेति ॥

(उद्द्योतः) ननु तरबाद्यनुत्पत्तावामन्तार्थे प्रकर्षादिप्रतीतिः कथमत आह—अनुप्रयोग एवेति । तदुत्पन्नतरपैवैतद्गतप्रकर्षप्रतीतिरित्यर्थः ॥ भाष्ये लुक्पदमदर्शनमात्रपरमिति भावः ॥

(पक्षान्तरभाष्यम्)

अथवा पुनरस्तु—कृदन्तं यन्मान्तमिति ॥

(आक्षेपभाष्यम्)

कथं प्रतामौ-प्रताम इति ?

(समाधानभाष्यम्)

आचार्यप्रवृत्तिर्ज्ञापयति—'न प्रत्ययलक्षणेनाव्ययसंज्ञा भवति' इति । यदयं प्रशान्शब्दं स्वरादिषु पठति ॥

(प्रदीपः) प्रशान्शब्दमिति । तस्य 'मो नो धातोः' इति नत्वस्यासिद्धत्वात्सिद्धमव्ययत्वमिति भावः ॥ तुल्यजातीयस्य धातोर्नियमेन व्यावृत्तिः क्रियते-इति कारयांचकारेति भवत्येव मान्तस्याव्ययसंज्ञा ॥ 'शान तेजने' इत्यस्य तु प्रशानिति रूपं न भवति, तस्य क्विबन्तस्य प्रयोगादर्शनात् । लावयतेर्लौरित्यस्यापि न भवति, अस्मादेव ज्ञापकाल्लाक्षणिकत्वाद्वाकारस्य ॥

(उद्द्योतः) धातुत्वेन तुल्यजातीयस्येत्याह—धातोरिति । तस्य क्विबन्तस्येति । अत्र चेदमेव भाष्यं मानम् ॥ प्रशामाविति तु शान्तिमद्वाचकस्य । शान्त्यर्थं स्यैव च गणे पाठः, तस्यैव स्वभावेन लिङ्गाद्यभावात् ॥ वस्तुतो गणे मान्तपाठः । प्रयोगे एव तु नत्वम् । यथा स्वरादीनां गणे रेफान्तपाठः प्रयोगे तु विसर्गादीति भाष्याशयः ॥ अस्मादेवेति । धातुमात्रापेक्षं ज्ञापकमिति भावः । लाक्षणिकत्वाद्वेति । वर्णग्रहणेऽपि तत्प्रवृत्तेरिति तात्पर्यम् ॥

(संनिपातपरिभाषाधिकरणम्)

(२१३ उपसंख्यानवार्तिकम् ॥ १ ॥)

॥ * ॥ कृन्मेजन्तश्चानिकारोकारप्रकृतिः ॥ * ॥

(भाष्यम्)

कृन्मेजन्तश्चानिकारोकारप्रकृतिरिति वक्तव्यम् । इह मा भूत्—आधये-आधेः, चिकीर्षवे-चिकीर्षोरिति ॥

(प्रदीपः) अनिकारोकारेति । एच एतद्विशेषणं न मकारस्य, व्यवच्छेद्यासंभवात् ॥ आधय इति । गुणे कृतेऽन्तरङ्गबहिरङ्गयोरिति न्यायादव्ययसंज्ञा स्यात्, न त्वयादयः ॥ अन्तरङ्गत्वादेव च सुब्लुक् स्यात् । परिभाषान्तरप्रयोजनकथनार्थं लक्षणप्रतिपदोक्तयोरित्येतदनाश्रितम् । लाक्षणिकं ह्यनुमेयं, प्रतिपदोक्तं तु प्रत्यक्षमिति तस्यैव ग्रहणं न्याय्यम् ॥

(उद्द्योतः) भाष्ये-अनिकारोकारेति । यत्त्वन्तग्रहणासामर्थ्यात्... बहुव्रीहिणा 'उपदेशे एजन्तं' इत्यर्थादत्र न दोष इति ॥ तन्न । परिभाषयैव सिद्धेऽन्तग्रहणं न कार्यमिति तदाशयात् ॥ गुणे कृत इति । तत्र कृत् सुबनपेक्षत्वेनान्तरङ्गाऽव्ययसंज्ञा, सुप्संबन्धजपेक्षत्वादयादयो बहिरङ्गा ॥ अन्तरङ्गत्वादेवेति । ननु वर्णमात्रापेक्षयाऽयादय एवान्तरङ्गाः ॥ एवं तर्हि अन्तरङ्गत्वेन बाधकत्वं लक्ष्यते । तेनान्तरङ्गानपीति न्यायेन लुगिति बोध्यम् । तेन च लुक इव तत्प्रयोजकानामपि प्राबल्यबोधनेनानेनैव गुणेऽयादीनाबधित्वाऽव्ययत्वं बोध्यम् ॥

(२१४ प्रकारान्तरप्रदर्शकवार्तिकम् ॥ २ ॥)

॥ * ॥ अनन्यप्रकृतिरिति वा ॥ * ॥

(भाष्यम्)

अथवा-अनन्यप्रकृतिः कृदव्ययसंज्ञो भवतीति वक्तव्यम् ॥

(आक्षेपभाष्यम्)

किं पुनरत्र ज्यायः ?

(समाधानभाष्यम्)

'अनन्यप्रकृतिः' इति वचनमेव ज्यायः । इदमपि सिद्धं भवति—कुम्भकारेभ्यो नगरकारेभ्य इति ॥

(तृतीयाक्षेपभाष्यम्)

तत्राह वक्तव्यम् ?

(२१५ सिद्धान्तिसमाधानवार्तिकम् ॥ ३ ॥)

॥ * ॥ न वा संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्येति ॥ * ॥

(भाष्यम्)

न वा वक्तव्यम् ।

किं कारणम् ?

'संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्य इति । एषा परिभाषा कर्तव्या ॥

(प्रदीपः) संनिपातलक्षण इति । संनिपातः-संश्लेषः. तन्निमित्तो यो विधिः स तद्विघातस्यानिमित्तं, तं संनिपातं यो विहन्ति तस्येत्यर्थः ॥

(उद्द्योतः) तद्विघातस्येति कर्मण्यणित्याह—तमिति न चानया लुको बाधेऽपि संज्ञाबाधे मानाभावः । साक्षात्परम्परया वा तद्विघातकमात्रस्यानया प्रतिबन्धात् । अत एव 'उपादास्त' इत्यत्र कित्त्वं न । अन्यथाऽनया साक्षादेज्विषयसन्निपातविघातकश्चिति चेति निषेधाप्रवृत्तिः स्यात् । कित्त्वं तु स्यादेव । तत्फलं तु सन्नियोगशिष्टत्वसिद्धिरेव । एवं च 'उपादेस्त' इति रूपं स्यात् । अत्र हि किदिति न कार्यातिदेशः, इत्त्वकाले तत्कार्यासंभवात् । तस्माद्व्यपदेशातिदेश एव । तस्मात्सन्निपातविघातकशास्त्रप्रवृत्तिनिमित्तातिदेशवत्संज्ञाया अप्यनेनाप्रवृत्तिः । अकजाद्यर्थसंज्ञा तु न, अन्तरङ्गायां तस्यां बहिरङ्गगुणादेरसिद्धत्वात् ॥

(आक्षेपभाष्यम्)

कः पुनरत्र विशेषः—एषा वा परिभाषा क्रियेत, अनन्यप्रकृतिरिति वोच्येत ?

(समाधानभाष्यम्)

अवश्यमेषा परिभाषा कर्तव्या । बहून्येतस्याः परिभाषायाः प्रयोजनानि ॥

(प्रयोजनप्रश्नभाष्यम्)

कानि पुनस्तानि ?

(प्रयोजनपरं भाष्यवार्तिकम् ॥)

प्रयोजनं ह्रस्वत्वं तुग्विधेर्ग्रामणिकुलम् ॥

(भाष्यम्)

ग्रामणिकुलं सेनानिकुलमिति । ह्रस्वत्वे कृते ह्रस्वस्य पिति कृति तुक् भवतीति तुक् प्राप्नोति ॥ 'संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्य' इति न दोषो भवति ॥

(प्रदीपः) ग्रामणिकुलमिति । इको ह्रस्व इति पूर्वोत्तरपदसन्निपातनिमित्तं ह्रस्वत्वं तुको न निमित्तम् । तुकि हि सति पूर्वोत्तरपदयोरानन्तर्यविघातः । यदा तु ह्रस्वमात्रस्य तुगागमो न तदन्तस्य, अवयवावयवश्च समुदायावयवो न भवति तदैतत्प्रयोजनं न त्वन्यथा ॥

(उद्द्योतः) पूर्वोत्तरेति । अधिकृतेनोत्तरपदेन पूर्वपदस्याक्षेपादिति भावः ॥ अवयवेति । तथाऽप्रतीतेरित्यभिमानः ॥ वस्तुतस्तु इगन्तपूर्वपदस्योत्तरपदसन्निपातविघातः पूर्वपदस्येगन्तत्वसंनिपातविघातश्चेति भाष्याशयः ॥ एवं वृत्रहभिरित्यत्र नान्तस्य स्वादिसन्निपातविघातः । नान्तस्वादिसन्निपातनिमित्तकपदत्वनिमित्तको हि नलोप इति ॥ लोके पाण्याद्यवयवाङ्गुल्यादेर्भुजपुरुषाद्यवयवत्वव्यवहारात् कैयटोक्तं चिन्त्यम् । किं च भविनेत्यादौ तासवयवेटो लघूपधाङ्गावयवैकत्वेन प्राप्तस्य गुणस्य दीधीवेवीटामिति निषेधो व्यर्थः स्यात् । न च ह्रस्वावयवत्वे तुको यदागमा इति न्यायेनैकग्रहणेन तुग्विशिष्टस्य ग्रहणान्न सन्निपातविघातः, ज्ञाने झुगिति ज्ञापकेन तदनङ्गीकारात् ॥ एतेनावयवावयवस्य समुदायावयवत्वे अवयवावयवेऽपि अवयविनां समवेतत्वापत्तौ घटस्यापि परमाणुषु समवेतत्वेनाप्रत्यक्षसमवेततया वायुवृक्षसंयोगवदप्रत्यक्षत्वं स्यादिति परास्तम् । भूयोऽवयवसंनिकर्षस्यैव फलबलात् कारणत्वेनाक्षतेः । संयोगप्रत्यक्षे तु यावदाश्रयप्रत्यक्षमेव हेतुः, फलबलादिति दिक् ॥

(प्रयोजननिराकरणभाष्यम्)

नैतदस्ति प्रयोजनम् । बहिरङ्गं ह्रस्वत्वम्, अन्तरङ्गस्तुक् । "असिद्धं बहिरङ्गमन्तरङ्गे" ॥

(प्रदीपः) बहिरङ्गमिति । द्विपदाश्रयत्वात् । यद्यपि ह्रस्वो नपुंसके प्रातिपदिकस्येति ह्रस्वत्वम्, तदपि अर्थाश्रयत्वाद्बहिरङ्गम्, तुक् तु वर्णाश्रयत्वादन्तरङ्गः । यदि तु सन्निपातलक्षण इत्याश्रीयते तदा ग्रामणिच्छत्रमित्यत्रापि तुग्न स्यात् । ह्रस्वत्वतुगागमयोस्त्वत्र साम्यादन्तरङ्गत्वं बहिरङ्गत्वं नास्तीति छलक्षणस्तुक् सिद्धो भवति ॥

(उद्द्योतः) असिद्धत्वेन समाधानं चावश्यकमित्याह—यद्यपीति ॥ अर्थाश्रयत्वादिति । इदं त्रयादेशे स्रन्तस्य प्रतिषेधो वक्तव्य इति स्थानिवत्सूत्रस्थेन वार्तिकेन तत्प्रत्याख्यानपरेण भाष्येण च विरुद्धम् । 'प्रातिपदिकरूपसमुदायाश्रयत्वात्' इति वक्तुं युक्तम् । तदेवाह—वर्णाश्रयत्वादिति । इयं च बहिरङ्गत्वेन सिद्धिर्नाजानन्तर्ये इति निषेधमनाश्रित्य ॥ 'कुलं ग्रामणि' इत्यत्र नपुंसकह्रस्वत्वे संनिपातपरिभाषयैव न तुक्, प्रातिपदिकस्याजन्तत्वसंनिपातेन जातह्रस्वस्य तद्विघातकत्वात् ॥ एतेन परनिमित्तकत्वेन कृत्वपित्त्वज्ञानसापेक्षत्वेन च तुगपि ह्रस्वसमान इति नपुंसकह्रस्वत्वे तुक् दुर्वार इत्यपास्तमिति अनुपदमेव वक्ष्यामः ॥ तुकि संनिपातपरिभाषाश्रयणे दोषमप्याह—यदि त्विति । अत्रापि वर्णमात्राश्रयत्वेन तुगन्तरङ्गः पूर्वपदोत्तरपदाश्रयो ह्रस्वो बहिरङ्गः, तैर्दोषेऽन्यस्यागणनाच्च । तस्मादत्र तुक् न भवत्येवेत्यन्ये ॥

(प्रयोजनपरं भाष्यवार्तिकम् ॥)

नलोपो वृत्रहभिः ॥

(भाष्यम्)

वृत्रहभिर्भ्रूणहभिरिति । अत्र नलोपे कृते ह्रस्वस्य पिति कृति तुक् भवतीति तुक् प्राप्नोति ।

"संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्य" इति न दोषो भवति ॥

(उद्द्योतः) वृत्रहभिरित्यादौ पदसंज्ञाद्वारा नलोपस्य संनिपातलक्षणत्वम् ॥

(प्रयोजननिराकरणभाष्यम्)

एतदपि नास्ति प्रयोजनम् । असिद्धो नलोपः तस्यासिद्धत्वान्न भविष्यति ॥

(प्रदीपः) असिद्धो नलोप इति । नलोपः सुप्स्वरेति-असिद्धं वहिरङ्गमिति वा ॥

(उद्द्योतः) असिद्धमिति । सुब्निरपेक्षतुगपेक्षया पदत्वद्वारा तदपेक्षनलोपो वहिरङ्ग इति भावः ॥

(२१६ प्रयोजनवार्तिकम् ॥ ७ ॥)

॥ * ॥ उदुपधत्वमकित्त्वस्य निकुचिते ॥ * ॥

(भाष्यम्)

उदुपधत्वमकित्त्वस्यानिमित्तम् ॥

क्व ?

'निकुचिते ।' निकुचितमित्यत्र नलोपे कृते "उदुपधाद्भावादिकर्मणोरन्यतरस्याम्" इत्यकित्त्वं प्राप्नोति ।

"संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्य" इति न दोषो भवति ॥

(प्रदीपः) निकुचित इति । कुचेर्भावे क्तप्रत्ययः । अनिदितामिति नलोपः । तत्र कित्त्वनिमित्तमुदुपधत्वं 'उदुपधात्-' इत्यकित्त्वस्यानिमित्तमिति गुणो न भवति ॥

(प्रयोजननिराकरणभाष्यम्)

एतदपि नास्ति प्रयोजनम् । अस्त्वत्राकित्त्वम् । "न धातुलोप आर्धधातुके" इति प्रतिषेधो भविष्यति ॥

(२१७ प्रयोजनवार्तिकम् ॥ ८ ॥)

॥ * ॥ नाभावो यञि दीर्घत्वस्यामुना ॥ * ॥

(भाष्यम्)

नाभावो यञि दीर्घत्वस्यानिमित्तम् ॥

क्व ?

'अमुना ।' नाभावे कृते "अतो दीर्घो यञि" "सुपि च" इति दीर्घत्वं प्राप्नोति ।

'संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्य' इति न दोषो भवति ॥

(प्रदीपः) अमुनेति । न मु न इत्यस्यायमर्थः—ने कर्तव्ये मुभावः सिद्धो भवति-इति, न तु ने परतोऽपि यद्दीर्घत्वं प्राप्नोति तत्र । तथाच तत्र मुभावस्यासिद्धत्वादकारान्तत्वाद्दीर्घप्रसङ्गः । तस्मिन् कृते अदसोऽसेरिति दीर्घस्य दीर्घ ऊकारः प्राप्नोति । ततश्च 'अमूना' इति स्यात् । उकारसन्निपातनिमित्तस्तु नाभावो दीर्घत्वस्याऽनिमित्तमिति सिद्धममुनेति ॥

(उद्द्योतः) यद्दीर्घत्वं प्राप्नोतीत्यस्य तत्रापि मुभावः सिद्ध इत्यर्थ इति शेषः । तत्रेत्यस्य च एवं चेत्यादिः ॥ क्वचित्तु 'प्राप्नोति तत्र । तथा च तत्र' इति पाठः ॥ असिद्धत्वादिति । त्राशासिद्धत्वादिति भावः ॥ कृतेऽदसोऽसेरिति । ननु मुत्वासिद्ध्या उकारे एवाकारबुद्धौ सुपि चेत्यन्तरतमे दीर्घ आकारे मस्य स्वत एव सत्त्वाद्दात्परत्वाभावेन कथमनेन दीर्घोकारप्रवृत्तिरिति चेन्न । लोकसिद्धसंनियोगशिष्टन्यायेन मुत्वस्यापि निवृत्तेर्दात्परत्वसत्त्वात् । न चाचः परस्मिन्निति स्थानिवत्त्वाद्दीर्घस्य नान्यतरापाय इति वाच्यम् । पूर्वत्रासिद्धीये न स्थानिवदिति निषेधात् ॥ लक्ष्ये लक्षणस्येति न्यायस्तु न, लक्ष्यभेदादित्यभिमानः ॥ केचित्तु अमाना अदाना इति वाऽऽपत्तिरित्याहुः ॥ दीर्घत्वस्येति । उकारस्वरूपविनाशकस्येत्यर्थः ॥

(प्रयोजननिराकरणभाष्यम्)

एतदपि नास्ति प्रयोजनम् । वक्ष्यत्येतत्—"न मु टाऽऽदेशे" इति ॥

(प्रदीपः) न मु टाऽऽदेश इति । अनेकविभक्त्यन्तस्तत्र समास आश्रितः—टाया आदेशः, टायामादेश इति ॥

(उद्द्योतः) नन्वेवमपि टाऽऽदेश एव सिद्धत्वं स्यादत आह—अनेकेति । अनेकविभक्त्यन्तसपूर्वपद इत्यर्थः । संबन्धसामान्यषष्ठ्या समास इति तात्पर्यम् ॥

(२१८ प्रयोजनवार्तिकम् ॥ ९ ॥)

॥ * ॥ आत्वं कित्त्वस्योपादास्त ॥ * ॥

(भाष्यम्)

आत्वं कित्त्वस्यानिमित्तं स्यात् ॥

क्व ?

उपादास्तास्य स्वरः शिक्षकस्येति । आत्वे कृते "स्थाघ्वोरिच्च" इतीत्वं प्राप्नोति ।

'संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्य' इति न दोषो भवति ॥

(प्रदीपः) उपादास्तेति । एज्विषय आत्वविधानादकित्त्वसन्निपातनिमित्तमात्त्वं स्थाघ्वोरिच्चेति कित्त्वस्यानिमित्तम् । कित्त्वसंनियुक्तं चेत्त्वमिति कित्त्वाभावे न भवति ॥

(उद्द्योतः) कित्त्वस्येति । भाष्येऽपि स्थाघ्वोरिच्चेति कित्त्वं प्राप्नोतीति पाठः । इत्त्वमिति पाठे कित्त्वसहितमित्त्वमित्यर्थः ॥ कित्त्ववारणेऽपीत्त्वं स्यादत आह—कित्त्वेति ॥

(प्रयोजननिराकरणभाष्यम्)

एतदपि नास्ति प्रयोजनम् । उक्तमेतत्—*दीङः प्रतिषेधः स्थाघ्वोरित्त्वे* इति ॥

(२१९ प्रयोजनवार्तिकम् ॥ १० ॥)

॥ * ॥ तिसृचतसृ ङीब्विधेः ॥ * ॥

(भाष्यम्)

तिसृचतसृत्वं ङीब्विधेरनिमित्तम् ॥

क ?

तिस्रस्तिष्ठन्ति-चतस्रस्तिष्ठन्ति । तिसृचतसृभावे कृते "ऋन्नेभ्यो ङीप्" इति ङीप् प्राप्नोति ।

'संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्य' इति न दोषो भवति ॥

(प्रयोजननिराकरणभाष्यम्)

एतदपि नास्ति प्रयोजनम् । आचार्यप्रवृत्तिर्ज्ञापयति-न तिसृचतसृभावे कृते ङीप् भवतीति । यदयं "न तिसृचतसृ" नामि दीर्घत्वस्य प्रतिषेधं शास्ति ॥

(प्रदीपः) यदयमिति । ननु समस्तार्थमेतत्स्यात्—प्रियतिसृणां ब्राह्मणानामिति । अत्र शब्दः पुंसि वर्तत इति नास्ति ङीपः प्राप्तिरिति केचित् ॥ तदयुक्तम् । न हि ङीब्विधानेऽर्थाधिकारोऽस्ति । तत्राऽवयवस्य स्त्रीत्वप्रवृत्तित्वात् ङीपः प्राप्तिः केन वार्यत इति ज्ञापकमेव ॥ ज्ञापकादेव च सिद्धत्वात् स्वस्रादिष्वनयोः पाठो न कर्तव्यो भवति ॥

(उद्योतः) नास्ति ङीप इति । यद्यन्तरङ्गत्वात्समासात्पूर्वमेव ङीबिति ॥ तन्न । अन्तरङ्गानपीति न्यायेनान्तर्वर्तिविभक्त्याश्रयतिस्रादेशस्याप्रवृत्तेः ॥ ज्ञापकमेवेति । ङ्यन्ते तु नास्य प्रवृत्तिः, विभक्तौ लिङ्गविशिष्टग्रहणात् ॥ नन्वेवं स्वस्रादिपाठो व्यर्थः स्यादत आह—ज्ञापकादेवेति । एवं चैतज्ज्ञापकपरभाष्यप्रामाण्यात्तत्पाठोऽप्रामाणिक इति भावः ॥

(प्रयोजनभाष्यम्)

इमानि तर्हि प्रयोजनानि—शतानि-सहस्राणि ।

नुमि कृते "ष्णान्ता षट्" इति षट्संज्ञा प्राप्नोति ।

'संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्य' इति न दोषो भवति ॥

(प्रदीपः) शतानीति । विभक्तिसन्निपातनिमित्तो नुमागमः षट्संज्ञाहेतुकस्य विभक्तिलुको न निमित्तम् । ष्णान्ता षडित्यन्तग्रहणमौपदेशिकप्रतिपत्त्यर्थमिति अत्र न भविष्यतीति चेत्, संख्यासंप्रत्ययार्थं बहुव्रीह्यर्थं तत् स्यादित्यदोषः ॥

(उद्योतः) विभक्तिलुक इति । तन्निमित्तसंज्ञायाश्चेत्यपि बोध्यम् ॥ अन्तग्रहणमिति । तत्सामर्थ्यादिति मन्यते ॥ सामर्थ्यमसिद्धमिति परिहारः—संख्येति । बहुव्रीहेः फलं संख्यासंप्रत्ययः ॥

(प्रयोजनभाष्यम्)

शकटौ-पद्धतौ । अत्वे कृते "अतः" इति टाप् प्राप्नोति ।

'संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्य' इति न दोषो भवति ॥

(प्रदीपः) शकटाविति । विभक्तिसंनिपातकृतमत्त्वं यदि टापो निमित्तं स्यात् आनन्तर्यं विहन्येत । शास्त्रीये च कार्येऽन्तादिवद्भावः, नानन्तर्ये लौकिके । टापि च सति शकटायामिति स्यात् ॥ अच्च घेरिति तपरकरणेनाप्यत्र टाप् निवर्तयितुं शक्यते । इदुतोर्हि स्थाने मात्रिक एवाकारो भविष्यति, भाव्यमानत्वाद्वा सवर्णस्याकारो ग्राहको न भविष्यतीति लक्षणान्तरेणापि प्राप्तस्य दीर्घत्वस्य निराकरणार्थं तपरकरणं संपद्यते ॥

(उद्योतः) विभक्तीति । घेः परस्य ङेरौत्, घेरन्तादेशश्चाकार इति सूत्रार्थात् ङ्यादेशौत्सन्नियोगेन विधीयमानमत्त्वमङ्गप्रत्ययसन्निपातकृतमित्यर्थः ॥ नन्वेकादेशेऽन्तवद्भावात् टाप् व्यवधायकोऽत आह—शास्त्रीये चेति ॥ ननु टापि वृद्ध्येकादेशे शकटाविति सिध्येदत आह— टापि चेति । वृद्धेः परत्वादाङ्त्वाच्च याडागमाविति भावः ॥ संपद्यत इति । तपरत्वाद्धि सवर्णदीर्घत्वं न स्यात् । टाप्तु स्यादेव । किं च शकटावित्यादौ वृद्धिरप्येवं न स्यादिति चिन्त्यमिदम् ॥

(प्रयोजनभाष्यम्)

इयेष-उवोष । गुणे कृते "इजादेश्च गुरुमतोऽनृच्छः" इत्याम् प्राप्नोति ।

"संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्य" इति न दोषो भवति ॥

(प्रदीपः) इयेषेति । आमि सति लुक् स्यादिति प्रकृतिप्रत्ययसंनिपातस्य विघातः स्यात् । उषविदेति विकल्प ओषांचक्रुः-ऊषतुरित्यादौ सावकाश इत्युवोषेति नित्यं आम् प्रसज्येत ॥ प्रतिपदविधेस्तु बल्वत्त्वात्परत्वाच्चात्रापि विकल्पेनैव भाव्यमित्यनुदाहरणमेतत् ॥ 'गुरुमतः' इति नित्ययोगे मतुबाश्रयणादपि शक्योऽत्रामभावः प्रतिपादयितुम् ॥

(उद्योतः) लुक् स्यादितीति । लुगभावेऽपि शकटावितिवत् तत्संनिपातेन गुणो जातस्तदानन्तर्यविघातस्य सत्त्वेनैतत्कथनस्योपयोगाभावः ॥ नन्वूषविदेत्याम्विधानादुवोषेत्यसङ्गतमत आह—उषविदेति । तत्र न द्विर्वचनात्प्राक् गुरुमत्त्वमिति भावः ॥ प्रतिपदविधेरिति । क्वचिद्गुणे क्वचिद्वित्वे एकादेशे गुरुमत्त्वादिजादेरित्येतस्याप्राप्तमिति भावः ॥ परत्वाच्चेति । तदुक्तस्य 'ऊषतुः' इत्यस्यावकाशत्वमभ्युपगम्येदमुच्यते ॥ उवोषेति ऊकारं द्वितीयान्तो वा भाष्ये पाठः ॥ उपेर्विकल्पेन पक्षे आमभावेऽपि कृतद्वित्वात् उवोषः दुर्वारत्वात्, रूपे चास्यैव विशेषः—उवोषाञ्चकारेति ॥ उपेत्यामि 'ओषांचकार' इति परे ॥ नित्ययोगेति । इजादेर्गुरोरित्युक्तावपि 'अनृच्छः' इति प्रतिषेधादिजादेर्गुरुमत इत्यर्थलाभे मतुब्ग्रहणादिति भावः ॥ परे त्वेवं सत्यनृच्छ इत्यस्यानर्थक्यापत्तिः । गुणात्पूर्वं प्राक् गुरुमत्त्वाभावात् । उम्मादीनां गुरुमतामामनापत्तेश्च, तेषामार्धलौकिकगुरुमत्त्वाभावादिति भाष्याशयमाहुः ॥

(परिभाषादोषाः)

(२२० दूषणवार्तिकम् ॥ ११ ॥)

॥ * ॥ तस्य दोषो वर्णाश्रयः प्रत्ययो वर्णविचालस्य ॥ * ॥

(भाष्यम्)

तस्यैतस्य लक्षणस्य दोषो वर्णाश्रयः प्रत्ययो वर्णविचालस्यानिमित्तं स्यात् ॥

क ?

"अत इञ्" दाक्षिः-प्लाक्षिः ॥

(प्रदीपः) दाक्षिरिति । प्रयोगे व्यवस्थितस्यैवेकारस्यान्वाख्यानमनेन क्रियत इति संनिपातलक्षणत्वं प्रत्ययस्य संभाव्यते ॥

(उद्योतः) नन्विञ्प्रत्ययो नोमयाधिष्ठानसम्बन्धलक्षणसंनिपाताश्रय इत्यत आह—प्रयोगे इति ॥ अन्वाख्यानं-साधुत्वेन ॥ प्रत्ययस्य-साधुत्वावच्छिन्नस्य ॥

(दूषणबाधकभाष्यम्)

न प्रत्ययः संनिपातलक्षणः ॥

(प्रदीपः) न प्रत्यय इति । कल्पितप्रकृतिप्रत्ययविभागेनान्वाख्यानात्प्रकृतेरविद्यमान एव प्रत्यय उत्पाद्यत इत्याशयः ॥

(उद्योतः) अविद्यमान एवेति । मन्दमध्यानां तथैव प्रतीतेः । साधुत्वान्वाख्यानेऽपि साधुत्वस्य संनिपातनिमित्तकत्वं, न प्रत्ययस्येति भावः ॥

(दूषणसाधकभाष्यम्)

अङ्गसंज्ञा तर्ह्यनिमित्तं स्यात् ॥

(प्रदीपः) अङ्गसंज्ञेति । सत्यामङ्गसंज्ञायामकारलोप इति स्यादानन्तर्यविघातः । तत्र वर्णविचालस्यानिमित्तं स्यादिति अङ्गसंज्ञाद्वारेणेत्यर्थः । अत्र केचित्-वर्णाश्रय इति व्याचक्षते । तेनात्रेयाद्यप्युदाहरणम् ॥ अन्ये त्ववर्णाश्रय इत्यकारप्रश्लेषमाहुः ॥

(उद्योतः) सत्यामिति । यस्मादित्यस्य प्रत्ययविधावुद्देश्यतावच्छेदकावच्छिन्नादित्यर्थेऽवर्णान्तादिञि तदङ्गसंज्ञमिति सूत्रार्थ इति भावः ॥ यद्यङ्गसंज्ञाऽनिमित्तम्, कथं तर्हि वार्तिके प्रत्यय इत्युक्तमत आह—तत्रेति ॥ आत्रेये 'इतश्चानिञः' इति ढक् ॥

परे तु वार्तिकस्यायमाशयः—निमित्तनिमित्तिनोः संबन्धवत् विशेषणविशेष्ययोः संबन्धोऽपि संनिपातः । एवं च प्रातिपदिकस्यादन्तत्वसंबन्धनिमित्तः प्रत्ययस्तद्विघातस्यानिमित्तमिति ॥ इममाशयमजानानः शङ्कते—न प्रत्यय इति (भाष्ये) ॥ एकदेश्युत्तरयति—अङ्गसंज्ञा तर्हीति । युक्तं चैतत् । उपजीव्यविरोधस्यान्याय्यत्वं हि एतन्न्यायमूलम् । तस्य च प्रकृतेऽपि सत्त्वात् । अतिप्रसङ्गस्तु त्वयेव मयाऽप्यनित्यत्वेन सुशकवारणः । अत एव ग्रामणि कुलमित्यादौ नपुंसकह्रस्वत्वे तुक् न, उपजीव्यस्य प्रातिपदिकान्तत्वसंबन्धस्य विघातात् ॥ बहिरङ्गपरिभाषयाऽसिद्धत्वं तु न । तस्य तस्याभावात् । दैवो गाङ्गेय इत्यादावप्यङ्गसंज्ञाया लोपनिमित्तत्वानापत्त्या वर्णाश्रय इत्यंशस्य वार्तिके वैयर्थ्यापत्तेश्चेत्याहुः ॥

(२२१ दूषणवार्तिकम् ॥ १२ ॥)

॥ * ॥-आत्वं पुग्विधेः क्रापयति ॥ * ॥

(भाष्यम्)

आत्वं पुग्विधेरनिमित्तं स्यात् ॥

क ?

क्रापयतीति ॥

(प्रदीपः) क्रापयतीति । णिचि वृद्धौ कृतायामात्वं पुक्नो न निमित्तं स्यात् । अङ्गस्य य आकारस्तस्य पुगित्यवयवभक्तं पुकं मत्वा दोषोपन्यासः ॥

(उद्योतः) आत्वं-'क्रीङ्जीनां णौ' इति ॥ स्वाङ्गस्याव्यवधायकत्वादाह—आकार इति । श्रुतत्वात्तस्यैव पुगिति भावः ॥

परे तु पुकोऽङ्गभक्तत्वेऽपि न क्षतिः, यावुभयोः संनिपातः पुग्निमित्तं तस्य विघातसत्त्वात् । यदागमा इति परिभाषया तद्ग्रहणेन ग्रहणेऽपि सत्रश्रुतसंनिपातस्याभावात् ॥ अत्र चेदमेव भाष्यं मानम्, ह्रस्वत्वं तुग्विधेरित्यादि च । सिद्धान्ताशयस्तु परिभाषाया अनित्यत्वमाश्रयणीयमित्येवेत्याहुः ॥

(२२२ दूषणवार्तिकम् ॥ १३ ॥)

॥ * ॥ पुक् ह्रस्वत्वस्यादीदपत् ॥ * ॥

(भाष्यम्)

पुक् ह्रस्वत्वस्यानिमित्तं स्यात् ॥

क ?

अदीदपत् ॥

(उद्योतः) भाष्ये—पुक् ह्रस्वत्वस्येति । आकारसंनिपातनिमित्तः पुक्, ह्रस्वे हि तद्विघातः स्पष्ट एव । न च ह्रस्वस्य चङ्परणिनिमित्तस्य णिनिमित्तपुगपेक्षया बहिरङ्गत्वेनासिद्धत्वात्कथमत्र परिभाषाप्राप्तिः ? एतद्भाष्यप्रामाण्येनानयाऽसिद्धस्यापि निवृत्तिस्वीकारात् । किं च तया शास्त्रीयकार्येऽसिद्धत्वेऽपि लौकिके संनिपातेऽसिद्धत्वाभावात् ॥

(२२३ दूषणवार्तिकम् ॥ १४ ॥)

॥ * ॥ त्यदाद्यकारष्टाब्विधेः ॥ * ॥

(भाष्यम्)

त्यदाद्यकारष्टाब्विधेरनिमित्तं स्यात् ॥

क ?

या सेति ॥

(२२४ दूषणवार्तिकम् ॥ १५ ॥)

॥ * ॥ इड्विधिराकारलोपस्य पपिवान् ॥ * ॥

(भाष्यम्)

इड्विधिराकारलोपस्यानिमित्तं स्यात् ॥

क ?

पपिवान् - तस्थिवानिति ॥

(उद्योतः) भाष्ये—इड्विधिरिति । वस्वेकाजादित्याकारान्तलक्षण इट् । नियमशास्त्राणां च विधिमुखेनैव प्रवृत्तिरिति भावः ॥

(२२५ दूषणवार्तिकम् ॥ १६ ॥)

॥ * ॥ मतुब्विभक्त्युदात्तत्वं पूर्वनिघातस्य ॥ * ॥

(भाष्यम्)

मतुब्विभक्त्युदात्तत्वं पूर्वनिघातस्यानिमित्तं स्यात् ॥

क ?

अग्निमान्-वायुमान्, परमवाचा-परमवाचे इति॥

(प्रदीपः) अग्निमानिति । पूर्वमुदात्तमाश्रित्य मतुप उदात्तत्वं क्रियमाणं पूर्वस्य निघातं न कुर्यात् ॥ परमवाचेति । अन्तोदात्तादुत्तरपदादिति विभक्त्युदात्तत्वं विधीयमानं पूर्वनिघातस्यानिमित्तं स्यात् ॥

(उद्योतः) पूर्वमिति । ह्रस्वनुड्भ्यामित्यन्तोदात्तादित्यनुवृत्तेरिति भावः ॥

(२२६ दूषणवार्तिकम् ॥ १७ ॥)

॥ * ॥ नदीह्रस्वत्वं संबुद्धिलोपस्य ॥ * ॥

(भाष्यम्)

नदीह्रस्वत्वं संबुद्धिलोपस्यानिमित्तं स्यात् ॥

क ?

नदि कुमारि ब्राह्मणि किशोरि ब्रह्मबन्धु इति । ह्रस्वत्वे कृते "एङ्ह्रस्वात्सम्बुद्धेः" इति संबुद्धिलोपो न प्राप्नोति ॥

(उद्योतः) ह्रस्वत्वं-अम्बार्थेत्यनेन ॥

(दूषणबाधकभाष्यम्)

मा भूदेवम् । ङ्यन्तादित्येवं भविष्यति ॥

(प्रदीपः) मा भूदिति । हल्ङ्याब्भ्यादिसूत्रे दीर्घग्रहणमंदृष्ट्वेदमुच्यते । तत्र कृतेऽपि ह्रस्वत्वे स्थानिवद्भावाद्भविष्यतीति भावः ॥ ब्रह्मबन्धुशब्दापेक्षया च नैतदुच्यते, तस्याङ्याबन्तत्वात् ॥

(दूषणसाधकभाष्यम्)

न सिध्यति । दीर्घादित्युच्यते, ह्रस्वान्ताच्च न प्राप्नोति ॥

इदमिह संप्रधार्यम्-ह्रस्वत्वं क्रियताम्, संबुद्धिलोप इति ।

किमत्र कर्तव्यम् ?

परत्वाद् ह्रस्वत्वम् ॥

(दूषणबाधकभाष्यम्)

नित्यः संबुद्धिलोपः । कृते ह्रस्वत्वे प्राप्नोति, अकृतेऽपि ॥

(प्रदीपः) नित्य इति । कार्यं तावन्नित्यं, तथेन केनचिल्लक्षणेन भवत्विति भावः ॥ संबुद्धिलोपस्यावकाशः–हे देवदत्तेति ॥

(उद्योतः) ननु एत्वग्रहणं निरवकाशत्वेन सन्निपातपरिभाषाबाधकं स्यादत आह—संबुद्धिलोपस्येति ॥

(दूषणसाधकभाष्यम्)

अनित्यः संबुद्धिलोपः । न हि कृते ह्रस्वत्वे प्राप्नोति ॥

किं कारणम् ?

संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्येति ॥

(आक्षेपोपसंहारभाष्यम्)

एते दोषाः समा भूयांसो वा । तस्मान्नार्थोऽनया परिभाषया ॥

(प्रदीपः) भूयांसो वेति । दुष्टत्वप्रतिपादनाय प्रकर्षारोपः । सर्वादिषु समशब्दस्य सर्वपर्यायस्य सर्वनामसंज्ञाविधानातुल्यवाचिनोऽत्र समा इति प्रयोगः । अस्ति समशब्दः सर्वपर्यायः । यथा-समराज्यं वर्तते, सर्वेषां राज्यं वर्तते इत्यर्थः । वेदेऽपि—मा नः समस्य दूढ्य इति प्रयोगः, सर्वस्य दुर्धियो मा न इत्यर्थः । तत्र प्रयोजनानामल्पत्वात्तान्येवोपसंख्यातव्यानीत्यर्थः ॥

(उद्योतः) भाष्ये-एते दोषाः समा इति । वार्तिककारोक्तसकलप्रयोजनापेक्षमिदम् ॥ यद्यपि प्रयोजनानि नव, दोषा अष्टौ; तथापि अल्पान्तरत्वात्समत्वोक्तिः । यद्वा—अन्यत्रापि दोषः संभाव्यत इत्यभिमानः ॥ ननूक्तदोषाणामुक्तप्रयोजनेभ्यो बहुत्वमेव न, कुतस्तदतिशयोऽत आह—दुष्टत्वेति ॥ अन्ये तूक्तेषु दूषितप्रयोजनानि त्यक्त्वा स्थितप्रयोजनत्रयापेक्षया भूयस्त्वोक्तिरित्याहुः ॥ ध्यायतेर्विच्नि षष्ठ्येकवचने आतो धातोरिति लोपे दुरो दाशनाशदभध्येष्विति उत्वे उत्तरपदादेः ष्टुत्वे दूढ्य इति, तदाह—दुर्धिय इति । सर्वस्य दुर्बुद्धेरंहतिः–उपद्रवो नः–अस्मान्मा वधीदित्यर्थः ॥ दुःस्थिता धीर्येषामिति विग्रहे गतिकारकपूर्वकत्वाभावाद्यण् न ॥ तस्मान्नार्थ इति पूर्वपक्षाशयमाह—तत्रेति ॥

(सिद्धान्तिसमाधानभाष्यम्)

नहि दोषाः सन्तीति परिभाषा न कर्तव्या, लक्षणं वा न प्रणेयम् । नहि भिक्षुकाः सन्तीति स्थाल्यो नाधिश्रीयन्ते । न च मृगाः सन्तीति यवा नोप्यन्ते ॥ दोषाः खल्वपि साकल्येन परिगणिताः । प्रयोजनानामुदाहरणमात्रम् ॥

कुत एतत् ?

नहि दोषाणां लक्षणमस्ति । तस्माद्यान्येतस्याः परिभाषायाः प्रयोजनानि तदर्थमेषा परिभाषा कर्तव्या, प्रतिविधेयं दोषेषु ॥ कृन्मेजन्तः ॥ ३९ ॥

(प्रदीपः) प्रतिविधेयमिति । तत्र विधानसामर्थ्या-

दाप्तो वर्णविचालो भविष्यति ॥ कष्टायेति ज्ञापकायशब्दे दीर्घो भविष्यति ॥ न यासयोरिति लिङ्गादाप् भविष्यति ॥ पपिवानिति । वस्वेकाजादित्ययं नियमः, इटो न त्वपूर्वोऽयं विधिरिति आकारस्य लोपः ॥ क्षापयतीत्याकारान्तभक्तः पुग व्यवधायकः ॥ अदीदपदिति लिङ्गाद् ह्रस्वः । यदयं मारणतोषणेति ज्ञानातेर्मित्त्वमुपधाह्रस्वार्थं शास्ति तज् ज्ञापयति — पुकि कृते उपधाह्रस्वत्वं भवतीति । न हि ज्ञानातेरकृते पुकि ह्रस्वभाविन्युपधा भवति ॥ अग्निमानिति अनुदात्तं पदमेकवर्जमिति परिभाषा स्वरविषया संनिपातपरिभाषां बाधते ॥ यङ्ह्रस्वादित्यत्रापि गुणात्संबुद्धेरिति वक्तव्ये ह्रस्वग्रहणसामर्थ्यात्संनिपातपरिभाषाऽभावः । दर्वीत्यत्र छन्दसि गुणाभावपक्षे छान्दसो लुग्भविष्यति ॥ ३९ ॥

(उद्द्योतः) सिद्धान्ती समाधत्ते — भाष्ये — न हीति ॥ परिभाषायाः कर्तव्यत्वे युक्त्यन्तरमप्याह सिद्धान्ती — दोषाः खल्वपीति ॥ लक्षणमिति । उपलक्ष्यक रूपं नास्तीत्यर्थः ॥ तत्र विधानति । यादृशप्रकृतिप्रत्ययसन्निपा तन्निमित्ताङ्गसंज्ञा तादृशसन्निपातविघात विना यस्येति लोपस्य चारितार्थ्याभावादिति भावः ॥ कष्टायेति । अकारसन्निपातनिमित्तो ङेर्यो यमादिनिमित्तदीर्घस्यानिमित्तं स्यादिति भावः ॥ न चैवं दोषाः साकल्येनेति भाष्यविरोधः । कष्टायेति यादेशो दीर्घस्वस्येति ग्रन्थो भाष्यपुस्तकेषु भ्रष्टोऽतो न दोषः । एवं च 'समाः' इत्यपि यथाश्रुतमेवेत्याहुः ॥ लिङ्गादिति । इत्वनिषेधवैयर्थ्यादिति भावः ॥ न त्वपूर्वं इति । क्रादिनियमादार्धधातुकस्येडिलेवेट् सिद्ध इति नेडाकारान्तसंनिपातनिमित्त इति भावः ॥

परे तु नियमशास्त्राणां विधित्वमेव, आर्थी त्वितरनिवृत्तिरित्यर्थस्य भाष्यसंमतत्वेनाकारान्तसन्निपातनिमित्त एवेडित्यनित्यत्वेनैवात्र समाधानं युक्तमित्याहुः ॥ आकारान्तेति । अङ्गस्येत्यनेन सामानाधिकरण्यस्योचितत्वादिति भावः ॥ अत्र यद्वक्तव्यं तत्प्रागेवोक्तम् ॥ तज्ज्ञापयतीति । अत एवं भरज्ञपीति निर्देशः सङ्गच्छते । मितां ह्रस्वे च 'उपधायाः' इत्यनुवर्तत इति भावः ॥ ह्रस्वभाविनीति । अचश्चेत्युपस्थितेरिति भावः ॥ अचश्चेत्यस्य श्रुतित्वेन तद्बाधकल्पनापेक्षयाऽस्यैवानुमितस्य लोकन्यायसिद्धस्य बाधकल्पनोचितेति तात्पर्यम् ॥ बाधते इति । ह्रस्वनुड्भ्यामित्यत्रोपस्थितयोपस्थितिसामर्थ्यादिति भावः ॥ गुणाभावेति । जसादिषु छन्दसि वावचनमिति वचनादिति भावः ॥ ३९ ॥

(३७ अव्ययसंज्ञासूत्रम् ॥ १ । १ । ६ आ. १२)

अव्ययीभावश्च ॥ १ । १ । ४१ ॥

(२२६ प्रयोजनवार्तिकम् ॥ १ ॥)

॥ * ॥ अव्ययीभावस्याव्ययत्वे प्रयोजनं लुङ्मुखस्वरोपचाराः ॥ * ॥

(भाष्यम्)

अव्ययीभावस्याव्ययत्वे प्रयोजनम् । किम् ?

लुङ्मुखस्वरोपचाराः ॥

लुक् — उपाग्नि, प्रत्यग्नि । "अव्ययात्—" इति लुक् सिद्धो भवति ॥

मुखस्वरः — उपाग्निमुखः, प्रत्यग्निमुखः । "नाव्ययदिक्शब्दगोमहत्स्थूलमुष्टिपृथुवत्सेभ्यः" इत्येष प्रतिषेधः सिद्धो भवति ॥

उपचारः — उपपयःकारः - उपपयःकाम इति ।

"अतः कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य" इति प्रतिषेधः सिद्धो भवति ॥

(प्रदीपः) अव्ययीभावश्च ॥ ४१ ॥ प्रयोजनमिति । मुखस्वरोपचारौ निवर्त्यमानौ प्रयोजनम्, यथा मशकार्थो धूम इति ॥

(उद्द्योतः) अव्ययीभावश्च ॥ ४१ ॥ उपचारो नाम अतः कृ इति विहितविसर्गस्थानिकसत्वम् ॥ यथा मशकार्थ इति । एतदेव निवृत्तिकारणमिति पातञ्जलैर्व्यवह्रियते ॥

(आक्षेपभाष्यम्)

किं पुनरिदं परिगणनम्, आहोस्विदुदाहरणमात्रम् ?

(समाधानभाष्यम्)

परिगणनमित्याह ॥ अपि खल्वप्याहुः — "यदन्यदव्ययीभावस्याव्ययकृतं प्राप्नोति तस्य प्रतिषेधो वक्तव्यः" इति ॥

(प्रदीपः) अपि खल्विति । एवं खल्वित्यर्थः । परिगणनमनेन दृढीक्रियते ॥

(उद्द्योतः) अनेनेति । ऋष्यन्तरवचनसंवादेनेत्यर्थः । तत्र 'वक्तव्यः' इत्यन्तं तत् । तत्र यदन्यदित्यन्यत्वे प्रतियोगिनश्चाय उक्ता इत्याहुः ॥

(अनुयोगभाष्यम्)

किं पुनस्तत् ?

(परिगणनाभावे दूषणभाष्यम्)

पराङ्गवद्भावेऽव्ययप्रतिषेधश्चोदितः, उच्चैरधीयान - नीचैरधीयानेत्येवमर्थम् । स इहापि प्राप्नोति — उपाग्न्यधीयान - प्रत्यग्न्यधीयान - इति ॥

(प्रदीपः) उपाग्न्यधीयानेति । अग्निसमीपे अधीयानेत्यर्थः । तत्र *षष्ठ्यामन्त्रितकारकवचनम्* इति पराङ्गवद्भावो भवति ॥

(उद्द्योतः) किं पुनस्तत्—पराङ्गवदित्यादिना तस्यैवोदाहरणप्रदर्शनम् ॥ षष्ठ्येति । अत्र च कारकत्वम् । तेन समुदायस्य षाष्ठमामन्त्रितस्य चेत्याद्युदात्तत्वम् ॥

(परिगणनाभावे दूषणभाष्यम्)

अकच्यव्ययग्रहणं क्रियते, उच्चकैर्नीचकैरित्येवमर्थम् । स इहापि प्राप्नोति — उपाग्निकं - प्रत्यग्निकम् ॥

(परिगणनाभावे दूषणभाष्यम्)

मुमि अव्ययप्रतिषेधश्चोद्यते, दोषामन्यमहः-दि-

घामन्या रात्रिरित्येवमर्थम् । स इहापि प्राप्नोति—उपकुम्भंमन्यः - उपमणिकंमन्य इति ॥

(परिगणनाभावे दूषणभाष्यम्)

"अस्य च्वौ" अव्ययप्रतिषेधश्चोद्यते, दोषाभूतमहः-दिवाभूता रात्रिरित्येवमर्थम् । स इहापि प्राप्नोति—उपकुम्भीभूतम्-उपमणिकीभूतम् ॥

(प्रत्याख्यानभाष्यम्)

यदि परिगणनं क्रियते, नार्थोऽव्ययीभावस्याव्ययसंज्ञया ॥

(आक्षेपभाष्यम्)

कथं यान्यव्ययीभावस्याव्ययत्वे प्रयोजनानि ?

(प्रथमप्रयोजननिरासभाष्यम्)

नैतानि सन्ति ॥ यत्तावदुच्यते—लुगिति । आचार्यप्रवृत्तिर्ज्ञापयति—भवत्यव्ययीभावाल्लुगिति । यदयम्—"नाव्ययीभावात्" इति प्रतिषेधं शास्ति ॥

(उद्द्योतः) भाष्ये-यदयं नाव्ययीभावादिति । स ह्यनन्तरत्वादव्ययादाप्सुप इत्यस्यैव निषेधो न तु सुपो धात्वित्यस्येति उपमणिकसुख इत्यादौ तन्निषेधेन चरितार्थमिति न भ्रमितव्यम् ॥

(तृतीयप्रयोजननिरासभाष्यम्)

उपचारः-अनुत्तरपदस्थस्येति वर्तते ॥

(द्वितीयप्रयोजने समाधानभाष्यम्)

तत्र मुखस्वर एकः प्रयोजयति । न चैकं प्रयोजनं योगारम्भं प्रयोजयति । यद्येतावत्प्रयोजनं स्यात्तत्रैवायं ब्रूयात्—'नाव्ययादव्ययीभावाच्च' इति ॥ अव्ययीभावश्च ॥ ४१ ॥

(प्रदीपः) न चैकमिति । सामान्यलक्षणमेकप्रयोजनार्थं न कर्तव्यमित्यर्थः ॥ तत्रैवायमिति । न चोक्तम्, तस्मान्मुखस्वरेणात्र भवितव्यमित्याहुः ॥ अन्ये तु वर्णयन्ति—अनव्ययमव्ययं भवतीत्यन्वर्थसंज्ञाविज्ञानान्मुखस्वरनिवृत्तिर्भविष्यतीति नार्थः सूत्रेणेति ॥ केचित्तु—स्वरादिपाठात्सिद्धायामव्ययसंज्ञायां पुनर्वचनमनित्यत्वज्ञापनार्थम् । तेन कतिपयान्येवाव्ययकार्याणि भवन्तीति नार्थः परिगणनेनेत्याहुः ॥ तेषां वचनमन्तरेण विशेषे प्रमाणाभावः ॥ ४१ ॥

(उद्द्योतः) न चोक्तमिति । भाष्ये 'यँदि' इत्यसन्दिग्धे संदिग्धवचनं वेदाः प्रमाणं चेत्-इतिवत् । तस्मात्तत्र ग्रहणं कर्तव्यम्, सूत्रं च न कार्यमिति भाष्याशय इति वयम् ॥ अन्ये त्विति । च्विना आरोपितमव्ययत्वं वास्तवमनव्ययत्वं च प्रतीयत इति यथालक्ष्यं किंचिदव्ययकार्यं भवति किंचिन्न-इतीष्टं सिद्धमिति भावः ॥ विशेषे-कार्यविशेषे ॥ किंच द्विर्बद्धं सुबद्धमिति न्यायेन पुनर्विधानात् सार्वत्रिकत्वमेव स्यादित्यपि द्रष्टव्यम् । एवं चाव्ययीभावस्याव्ययत्वात्त्वयत्त्रेति हरदत्ताद्युक्तं चिन्त्यम् । भाष्यविरोधात् ॥ अन्ये तु—मुखस्वरे नाव्ययीभावादिति नोक्तम् । सूत्रं च कृतम् । तस्मादन्यदपि प्रयोजनम्—तथा उपकूलमित्यादौ षष्ठीसमासप्रतिषेधादीत्याहुरिति मतं हरिटीकायां स्पष्टम् । तत् 'अपि खल्वप्याहुः' इत्यादिभाष्याननुगुणम् ॥ ४१ ॥

(अथ सर्वनामस्थानसंज्ञासूत्रे)

(३७ सर्वनामस्थानसंज्ञासूत्रम् ॥ १ । १ । ६ आ. १३)

शि[११] सर्वनामस्थानम् ॥ १ । १ । ४२ ॥

(३८ सर्वनामस्थानसंज्ञासूत्रम् ॥ १ । १ । ६ आ. १४)

सुडनपुंसकस्य ॥ १ । १ । ४३ ॥

(२२८ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ शि सर्वनामस्थानं सुडनपुंसकस्येति चेज्जसि शिप्रतिषेधः ॥ * ॥

(भाष्यम्)

शि सर्वनामस्थानं सुडनपुंसकस्येति चेज्जसि शिप्रतिषेधः प्राप्नोति । कुण्डानि तिष्ठन्ति, वनानि तिष्ठन्ति ॥

(प्रदीपः) शि सर्व० ॥ ४२ ॥ सुडनपुंसकस्येति चेदिति । अस्मिन् सूत्रन्यासे दोषः । 'सुट् स्त्रीपुंसयोः' इत्यस्मिन्न्यासे न दोष इत्यर्थः ॥

(दूषणान्तरभाष्यम्)

असमर्थसमासश्चायं द्रष्टव्यः-अनपुंसकस्येति । न हि नञो नपुंसकेन सामर्थ्यम् ॥

केन तर्हि ?

भवतिना । न भवति नपुंसकस्येति ॥

(प्रदीपः) प्रसज्यप्रतिषेधाश्रयेण पूर्वपक्षः, पर्युदासाश्रयेण सिद्धान्तः ॥

(उद्द्योतः) शि सर्वना० ॥ ४२ ॥ भाष्ये—असमर्थसमासश्चेति दूषणान्तरम् । तत्रासामर्थ्य—असंबन्धात् । चेन वाक्यभेदस्यापि संग्रहः ॥ पर्युदासेति । एवं हि समर्थसमासैकवाक्यते लभ्येते ॥ यद्यपि पर्युदासेऽपि लक्षणा, तथापि दोषद्वययुक्तप्रसज्यप्रतिषेधापेक्षया लघुरेवेति भावः ॥ वस्तुतो नञो निपातत्वेनानेकार्थत्वात्पर्युदासपक्षे लक्षणा-इति रिक्तं वचः ॥ पर्युदासपक्षे सुडित्यनेनैकवाक्यतया तस्याप्राप्तावपि आद्यस्याप्राप्तौ न मानमिति तात्पर्यम् ॥

(समाधानभाष्यम्)

यत्तावदुच्यते—* शि सर्वनामस्थानं सुडनपुंसकस्येति चेज्जसि शिप्रतिषेधः*—इति ॥

(२२९ समाधानवार्तिकम् ॥ १ ॥)

॥ * ॥ नाप्रतिषेधात् ॥ * ॥

(भाष्यम्)

नायं प्रसज्यप्रतिषेधः—नपुंसकस्य नेति ॥

किं तर्हि ?

पर्युदासोऽयम्—यदन्यन्नपुंसकादिति । नपुंसके न व्यापारः । यदि केनचित्प्राप्नोति, तेन भविष्यति । पूर्वेण च प्राप्नोति ॥

(उद्द्योतः) भाष्ये—नपुंसके न व्यापार इति । निषेधस्येति शेषः ॥

(२२० समाधानवार्तिकम् ॥ २ ॥)

॥ * ॥ अप्राप्तेर्वा ॥ * ॥

(भाष्यम्)

अथवा—अनन्तरा या प्राप्तिः सा निषिध्यते ॥ कुत एतत् ? 'अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा' इति । पूर्वा प्राप्तिरप्रतिषिद्धा, तया भविष्यति ॥

(प्रदीपः) **अप्राप्तेर्वेति** । प्रसज्यप्रतिषेधेऽप्यदोषः । तत्र **सुडित्यनेन** या प्राप्तिः, सा प्रतिषिध्यते । न तु **शि सर्वनामस्थानमिति** प्राप्तिः । अन्यथा **शि सर्वनामस्थानमिति** निरवकाशं स्यात् । नपुंसकस्यैव हि शिः संभवति ॥

(उद्द्योतः) अप्राप्तेरिति वार्तिकस्य पूर्वसूत्रविहितसंज्ञायाः प्रतिषेधाप्राप्तेरिति अक्षरार्थः ॥ भाष्ये तु वस्त्वर्थं उच्यते ॥ अन्यथेति । सुडित्यनपेक्ष्य नपुंसकसंबन्धिमात्रस्य निषेध इत्यभिमानः ॥ सुट्संबन्धे तु इदं चिन्त्यं, शसः शौ चरितार्थत्वात् ॥

(आक्षेपभाष्यम्)

ननु चेयं प्राप्तिः पूर्वां प्राप्तिं बाधते ॥

(प्रदीपः) **ननु चेयमिति** । परत्वादित्यर्थः । प्रतिषेधयुक्तायुक्तत्वाच्च विरोधसद्भावः । तत्र परत्वात् सुडिति प्राप्तिः पूर्वां प्राप्तिं बाधते, तामपि प्रतिषेध इति दोषः ॥

(उद्द्योतः) ननु संज्ञाया एकत्वेन कार्यैक्ये विरोधाभावात्कः परत्वमत आह—प्रतिषेधेति । शसि सावकाशत्वात् । एवं चोभयोर्यौगपद्यासंभवरूपो विरोधोऽस्तीति भावः ॥ **पूर्वां प्राप्तिमिति** । एवं च सकृद्गतिन्यायेन पुनर्न प्रवर्तत इति भावः ॥

(समाधानभाष्यम्)

नोत्सहते प्रतिषिद्धा सती पूर्वां बाधितुम् ॥

(प्रदीपः) **नोत्सहत इति** । अपवादविषयपरिहारेणास्याः प्रवर्तनादित्यर्थः ॥

(उद्द्योतः) अपवादेति । एवं च स्वयमप्रवर्तमाना कथमन्यबाधिकेति तच्चर्चायावसरो नेति भावः ॥

(दूषणान्तरसमाधानभाष्यम्)

यदप्युच्यते—असमर्थसमासश्चायं द्रष्टव्यः—इति । यद्यपि वक्तव्यः, अथवैतर्हि बहूनि प्रयोजनानि ॥

कानि ?

असूर्यंपश्यानि मुखानि, अपुनर्गेयाः श्लोकाः, अश्राद्धभोजी ब्राह्मण इति ॥ सुड० ॥ ४३ ॥

(प्रदीपः) **अथवैतर्हीति** । इदानीमित्यर्थः । तत्र **स्त्रीपुंसयोरिति** वक्तव्ये **अनपुंसकस्येति** वचनं ज्ञापकम्—प्रसज्यप्रतिषेधेऽपि नञ्समासोऽस्तीति ॥ ४३ ॥

(उद्द्योतः) इदानीमित्यर्थ इति । तथापीत्यर्थ इत्युचितम् । यद्यपि वक्तव्य इत्युपक्रमात् ॥ स्त्रीपुंसयोरिति । मात्राधिक्येऽपि स्पष्टप्रतिपत्त्यर्थमित्यर्थः ॥ पुंस्त्रियोरिति तु वक्तुमशक्यम्, तस्यासाधुत्वात्—इति बोध्यम् ॥ अत्र पर्युदासप्रसज्यप्रतिषेधयोः समफलत्वोक्त्या शास्त्रप्रापितस्य प्रतिषेधे विकल्प इति मं प्रसङ्कोक्तं चिन्त्यम् । सामान्यविशेषन्यायेन बाधस्यैवौचित्यात् । स्वाभावे संज्ञाविहितस्यैव च प्रतिषेध इत्यादि मञ्जूषायां विस्तरः ॥ ४३ ॥

(इति सर्वनामस्थानसंज्ञासूत्रे)

(३९ विभाषासंज्ञासूत्रम् ॥ १।१।६ आ. १५ ॥)

न वेति विभाषा ॥ १ । १ । ४४ ॥

(अर्थसंज्ञाधिकरणम्)

(२२१ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ नवेतिविभाषायामर्थसंज्ञाकरणम् ॥ * ॥

(भाष्यम्)

नवेतिविभाषायामर्थस्य संज्ञा कर्तव्या । नवाशब्दस्य योऽर्थस्तस्य संज्ञा भवतीति वक्तव्यम् ॥

(प्रदीपः) **न वेति० ॥४४॥ नवेतिविभाषायामिति** । समुदायस्यानुकरणत्वादनुकरणस्य चानुकार्येणार्थवत्त्वात्प्रातिपदिकत्वे सति विभक्त्युत्पत्तिः । स्त्रीप्रत्यये च तदादिनियमाभावाद्याडामौ भवतः । **अथवा** नवेत्युच्चार्य या विभाषा कृता तस्यां-इति व्याख्या । तत्र लोके क्रियापदसंनिधाने नवाशब्दयोर्योऽर्थो द्योत्यो विकल्पप्रतिषेधलक्षणः स संज्ञीत्यर्थः । अन्यथा विभाषाप्रदेशेषु नवाशब्दावेवादेशौ स्याताम् ॥

(उद्द्योतः) न वेति विभाषा ॥ ४४ ॥ ननु समुदायस्य समासग्रहणनियमेनाप्रातिपदिकत्वात् नवेतिविभाषायामित्यनुपपन्नमत आह—समुदायस्येति । वार्तिकोच्चारितसमुदायस्येत्यर्थः ॥ नन्वेवमपि समुदायस्यानावन्तत्वात् कथं याडादीत्यत आह—स्त्रीप्रत्यये चेति । स्त्रीप्रत्यये चानुपसर्जने नेति ष्यङः संप्रसारणमित्यत्र भाष्यपठितवचनेनेति भावः ॥ यत्तु हल्ङ्याब्भ्य इति दीर्घग्रहणादिति । तन्न । बहुश्रेयसीत्यादौ लोपार्थं प्रत्ययग्रहण इति तदन्तविधिना ङ्यन्तेत्यर्थे तस्य स्वादिप्रत्ययलब्धयस्माद्विधिस्तदादेरित्येतद्विशेषणतया ङ्यन्तान्तेत्यर्थेन निष्कौशाम्बिव्यावृत्तये दीर्घग्रहणस्यावश्यकत्वादिति दिक् ॥ अनुकरणस्यावन्तत्वं तु प्रकृतिवदनुकरणमिति न्यायात् । तस्यानित्यत्वाच्च न प्रत्ययान्तत्वप्रयुक्तप्रातिपदिकत्वनिषेध इति बोध्यम् ॥ अथवेति । कृता—उच्चारिता । समासत्वादेव प्रातिपदिकत्वम्, असमासेऽपि लिङ्गविशिष्टपरिभाषया विभक्तिरिति भावः ॥ नामपदसन्निधाने 'नवा शाटी' इत्यादौ प्रत्ययार्थावगतेराह—क्रियापदेति ॥ अन्यथेति । प्रकरणादिवशाच्चार्थविशेषावसाय इति भावः ॥

(भाष्यम्)

किं प्रयोजनम् ?

(२३२ आक्षेपसाधकवार्तिकद्वितीयखण्डम् ॥ १ ॥)

॥ * ॥ शब्दसंज्ञायां ह्यर्थासंप्रत्ययो यथाऽन्यत्र ॥ * ॥

(भाष्यम्)

शब्दसंज्ञायां सत्यामर्थस्यासंप्रत्ययः स्यात् । 'यथाऽन्यत्र' । अन्यत्रापि हि शब्दसंज्ञायां शब्दस्य संप्रत्ययो भवति, नार्थस्य ॥

क्वान्यत्र ?

"दाधा घ्वदाप्" "तरप्तमपौ घः" इति । घुग्रहणेषु घग्रहणेषु च शब्दस्य संप्रत्ययो भवति, नार्थस्य ॥

(प्रदीपः) घुग्रहणेष्विति । शब्दस्य संज्ञाकरणात्प्रदेशेषु तस्यैव संप्रत्यय इत्यर्थः ॥

(उद्द्योतः) ननु दाधा घ्वित्यादौ न घुशब्दादिना दाधादीनां प्रत्ययः, किंतु दाधाशब्दैरेवेत्यत आह—प्रदेशेष्विति ॥ भाष्ये घुग्रहणेष्वित्यादेः–घुप्रदेशेष्वित्यर्थः ॥

(आक्षेपभाष्यम्)

तत्तर्हि वक्तव्यम् ॥

(समाधानभाष्यम्)

न वक्तव्यम् ॥

(२३३ समाधानवार्तिकम् ॥ २ ॥)

॥ * ॥ इतिकरणोऽर्थनिर्देशार्थः ॥ * ॥

(भाष्यम्)

इतिकरणः क्रियते सोऽर्थनिर्देशार्थो भविष्यति ॥

(प्रदीपः) इतिकरण इति । क्रियत इति—करणः, कर्मणि ल्युट्, इतिश्चासौ करणश्चेति विशेषणसमासः ॥ 'क्रियते' इति सामान्यविशेषभावेन निर्देशः ॥

(उद्द्योतः) करणल्युटि अर्थासङ्गतेराह—कर्मणीति । बाहुलकादिति भावः ॥ सामान्येति । पाकं पचतीतिवत् ॥

(आक्षेपभाष्यम्)

किं गतमेतदितिना, आहोस्विच्छब्दाधिक्यादर्थाधिक्यम् ?

(प्रदीपः) शब्दाधिक्यादिति । उपहासपरमेतच्चोदकस्य वचनम् । अशब्दार्थस्यालाभादिति भावः ॥

(समाधानभाष्यम्)

गतमित्याह ॥

कुतः ?

(समाधाने भाष्यवार्तिकम् ॥)

लोकतः ॥

(भाष्यम्)

तद्यथा—'गौरित्ययमाह' इति गोशब्दादितिकरणः प्रयुज्यमानो गोशब्दं स्वस्मात्पदार्थात्प्रच्यावयति । सोऽसौ स्वस्मात्पदार्थात्प्रच्युतः-याऽसावर्थपदार्थकता तस्याः-शब्दपदार्थकः संपद्यते ॥ एवमिहापि नवाशब्दादितिकरणः प्रयुज्यमानो नवाशब्दं स्वस्मात्पदार्थात्प्रच्यावयति । सोऽसौ स्वस्मात्पदार्थात्प्रच्युतः-याऽसौ शब्दपदार्थता तस्याः-लौकिकमर्थं सम्प्रत्याययति—नवेति यद्गम्यते–नवेति यत्प्रतीयते–इति ॥

(प्रदीपः) गौरित्ययमाहेति । यद्यपि नित्ये शब्दार्थसंबन्धे उपात्तस्यार्थस्य त्यागो नास्ति, तथापि प्रसिद्धिवशादेतदभिधीयते—अर्थपदार्थकतायाः प्रच्युतः—इति । तत्त्वतस्त्वादावेव स्वरूपपदार्थको गोशब्दः प्रयुक्तः, सादृश्यात्तु तमर्थमनभिव्यक्तं 'इति'शब्दो द्योतयतीति पदार्थविपर्यासकृत्—इत्युच्यते ॥ अर्थपदार्थकतेति । संबन्धे भावप्रत्ययः । संबन्धात्प्रच्युतोऽतोऽर्थात् प्रच्युतो भवति ॥

(उद्द्योतः) भाष्ये—स्वस्मात्पदार्थात्प्रच्युतः शब्दपदार्थकः संपद्यत इत्यन्वयः ॥ स्वस्मात्पदार्थादित्यस्य विवरणम्—याऽसाविति । दार्ष्टान्तिके च शब्दपदार्थता, 'स्वं रूपं' इति वचनात् ॥ तस्या इत्यस्य प्रच्युत इति शेषः ॥ कोऽसौ लौकिकोऽर्थस्तत्राह—नवेति यद्गम्यत इति ॥ तद्विवृणोति—नवेति यत्प्रतीयत इति । स लौकिकोऽर्थ इति शेषः ॥ यद्यपीति । एवं च स्वस्मात्पदार्थादित्यनुपपन्नं, सर्वस्यापि स्वपदार्थत्वात् । प्रच्युतिश्चानुपपन्नेति भावः ॥ त्यागो नास्तीति चार्थान्तरग्रहणाभावस्याप्युपलक्षणम् ॥ प्रसिद्धिवशादिति । लोकप्रसिद्ध्यैव तत्र स्वपदार्थत्वव्यवहारः । तेषामेवास्यायं प्रसिद्धोऽर्थस्त्यक्तोऽप्रसिद्धश्च गृहीत इति प्रसिद्ध्या भाष्ये प्रच्युत्यङ्गीकारावुक्ताविति भावः ॥ वस्तुतो न प्रच्युत्यादिकमित्याह—तत्त्वत इति ॥ सादृश्यादिति । अर्थभेदाच्छब्दभेद इति पक्षे इदम् ॥ एकशब्दत्वे त्वभेदादिति बोध्यम् ॥ वस्तुतः प्रच्युत्यङ्गीकारौ तयोरर्थयोर्बोधाविषयत्वबोधविषयत्वे एव, न तु मुख्याविति बोध्यम् ॥ पदार्थविपर्यासकृदिति । लोके शब्दविशेषणकार्थप्रतीतिः, शास्त्रेऽर्थविशेषणकशब्दस्य । इतिशब्दसमभिव्याहारे विपरीतमिति विपर्यासः ॥ भाष्येऽपि—स्वस्मात्पदार्थात् प्रच्युत इत्यस्य विशेष्यभूतादिति शेषः ॥ अन्यथाऽर्थप्रतीतेः शब्दानालिङ्गिताया अभावेन एतदसङ्गतिः स्यादिति दिक् ॥

(समानशब्दसंज्ञानिरसनाधिकरणम्)

(२३४ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ समानशब्दप्रतिषेधः ॥ * ॥

(भाष्यम्)

समानशब्दानां प्रतिषेधो वक्तव्यः । नवा कुण्डिका - नवा घटिकेति ॥

(प्रदीपः) **समानशब्दप्रतिषेध इति** । समानः शब्दो वाचको येषामर्थानां तेषामित्यर्थः ॥

(उद्द्योतः) इतिकरणस्यार्थनिर्देशार्थत्वे स्थिते नैव समानानां शब्दानां प्राप्तिरत आह—**समान इति** ॥

(आक्षेपभाष्यम्)

किंच स्यात्, यद्येतेषां विभाषा संज्ञा स्यात्?

(समाधानभाष्यम्)

"विभाषा दिक्समासे बहुव्रीहौ"—दक्षिणपूर्वस्यां शालायाम् । अचिरकृतायां संप्रत्ययः स्यात् ॥

(प्रदीपः) **विभाषा दिक्समास इति** । विभाषाशब्देनाभिनवलक्षणोऽर्थः प्रत्याय्यते । तत्र प्रत्यग्रवाची यो दिक्समास इति संप्रत्ययः स्यात् । तत्र दिशो नित्यत्वान्नवपुराणत्वासंभवात्तन्निमित्तो यदा शालायां व्यपदेशः—दक्षिणपूर्वा शाला सा चाभिनवा, तदा संज्ञा स्यादित्यर्थः । संज्ञाकार्यव्यङ्ग्यं च प्रत्यग्रत्वं स्यात् ॥

(उद्द्योतः) प्रत्यग्रेति । यद्यपि न चेह वयं विभाषाग्रहणेन सर्वादीन्यभिसंबध्नीम इति भाष्यपर्यालोचनया सर्वादिविशेषणत्वलाभात् प्रत्यग्रत्वं समासविशेषणमयुक्तम्, तथापि दिग्वाचकसर्वादीनामर्थस्य दिशो नवपुराणत्वासंभवादुदाहरणपरभाष्याच्च तत्र सर्वादीनीत्यनेन तद्घटितसमासो लक्षणीय इति भावः ॥ तन्निमित्त इति । लक्षणयेत्यर्थः ॥ तदा संज्ञेति । न बहुव्रीहाविति निषेधे प्राप्ते इदं नित्यार्थं स्यादिति भावः ॥ भाष्ये—अचिरकृताया मिति । तस्यां बोध्यायामित्यर्थः ॥ संप्रत्ययः स्यादित्यस्य संज्ञाया इति शेषः ॥

(२२५ समाधानवार्तिकम् ॥ २ ॥)

॥ * ॥ न वा विधिपूर्वकत्वात् प्रतिषेधसंप्रत्ययो यथा लोके ॥ * ॥

(भाष्यम्)

न वा एष दोषः ॥

किं कारणम्?

'विधिपूर्वकत्वात् ।' विधाय किंचित् न वेत्युच्यते, तेन प्रतिषेधवाचिनः संप्रत्ययो भवति । तद्यथा लोके—ग्रामो भवता गन्तव्यो न वा, नेति गम्यते ॥

(प्रदीपः) **न वा विधिपूर्वकत्वादिति** । प्रदेशवाक्यार्थं पर्यालोच्येयं संज्ञा व्यवस्थाप्यते । प्रदेशेषु च कार्याणि विधाय विभाषाशब्द उच्चारितो नवाशब्दार्थं गमयति । तत्र लोकवन्निपातार्थावगतिर्भवति, न तु प्रत्यग्रार्थावगतिरित्यर्थः ॥

(उद्द्योतः) ननु प्रदेशे विभाषादिगित्यादौ न नवाशब्द उच्चारितः, नवेति विभाषेति सूत्रे तु न किंचिद्विधायोक्तम्, पूर्वोत्तरसाहचर्येणास्य संज्ञासूत्रत्वादित्यत आह—**प्रदेशेष्विति** ॥ इयं संज्ञेति । नवेतिविभाषेत्येतत्संज्ञासूत्रार्थ इत्यर्थः ॥ कार्याणि—सर्वनामसंज्ञादीनि ॥ नवार्थ—नवाशब्दार्थम्, विभाषाशब्दस्यार्थसंज्ञात्वात् । क्वचित्तु तथैव पाठः । भाष्ये—न वेत्युच्यते इत्यस्य—तदर्थबोधको विभाषाशब्द उच्यते इत्यर्थः ॥ प्रतिषेधवाचिन इति । प्रतिषेधवाच्ययं शब्द इति प्रत्ययो भवतीत्यर्थः ॥ न त्विति । एवं च प्रदेशानुगुण्येन प्रकृतसूत्रेऽपि न प्रत्यग्रवाचिनो ग्रहणमित्यर्थः ॥

(समाधानबाधकभाष्यम्)

अस्ति कारणम्—येन नवेत्युक्ते लोके प्रतिषेधवाचिनः संप्रत्ययो भवति ॥

किं कारणम्?

विलिङ्गं हि भवान् लोके निर्देशं करोति ।

अङ्ग हि समानलिङ्गो निर्देशः क्रियतां प्रत्यग्रवाचिनः संप्रत्ययो भविष्यति । तद्यथा—'ग्रामो भवता गन्तव्यो नवः', प्रत्यग्र इति गम्यते ॥

(प्रदीपः) **विलिङ्गमिति** । भिन्नलिङ्गं, व्यधिकरणमित्यर्थः ॥ विलिङ्गत्वेन वैयधिकरण्यं लक्ष्यते, न तु प्रतिषेधवाचिनो नवाशब्दस्य लिङ्गयोगोऽस्ति ॥

(उद्द्योतः) भिन्नेति । अग्रे समानलिङ्ग इति दर्शनाद्विशब्दो भिन्नार्थ इति भावः ॥ न त्विति । अव्ययत्वादिति भावः ॥

(समाधानसाधकभाष्यम्)

एतच्चैव न जानीमः—क्वचिद्व्याकरणे समानलिङ्गो निर्देशः क्रियत इति ॥

(प्रदीपः) **एतच्चैवेति** । नैव क्वचिद् व्याकरणे समानलिङ्गो निर्देश इत्यर्थः ॥ 'विभाषा सेनासुरा-' इति यद्यपि समानलिङ्गो निर्देशः, तथापि भिन्नविभक्तित्वात्सामानाधिकरण्याभावः ॥

(उद्द्योतः) नैवेति । भाष्ये—क्वचित् क्रियत इत्येतच्चैव न जानीम इत्यन्वयः ॥ न वा विधीत्युक्तवतोऽयं ग्रन्थः । एवं च शास्त्रे समानलिङ्गनिर्देशस्य क्वाप्यभावात् न क्वापि प्रत्यग्रार्थावगतिरित्याशयः ॥

(समाधानसाधकशेषभाष्यम्)

अपि चात्र कामचारः प्रयोक्तुः शब्दानामभिसंबन्धे । तद्यथा—'यवागूर्भवता भोक्तव्या न वा' । यदा यवागूशब्दो भुजिना संबध्यते भुजिर्नवाशब्देन, तदा प्रतिषेधवाचिनः संप्रत्ययो भवति—'यवागूर्भवता भोक्तव्या न वा', नेति गम्यते ॥ यदा यवागूशब्दो नवाशब्देनाभिसंबध्यते न भुजिना, तदा प्रत्यग्रवाचिनः संप्रत्ययो भवति । यथा—'यवागूर्नवा भवता भोक्तव्या', प्रत्यग्रेति गम्यते ॥

न चेह वयं विभाषाग्रहणेन सर्वादीन्यभिसंबध्नीमः—दिक्समासे बहुव्रीहौ सर्वादीनि विभाषा भवन्तीति ॥

किं तर्हि?

भवतिरभिसंबध्यते—दिक्समासे सर्वादीनि भवन्ति विभाषेति ॥

(प्रदीपः) अपि चेति । तत्र सामर्थ्याद्विशेषावगतिः ॥ यदाऽप्राप्ते यवागूभोजने वाक्यमुदीर्यते, तदा प्रत्यग्रार्थावगतिः । यदा त्वातुरं प्रति गुरुभोजननिषेधार्थमुच्यते, तदा निषेधार्थावगतिः ॥ न चेहेति । क्रियायाः प्राधान्यात्सैव विभाषाग्रहणेन संबध्यते, न तु तदङ्गमित्यर्थः । तदेवं स्थितमेतत्—न वा विधिपूर्वकत्वादिति ॥

(उद्द्योतः) ननूभयविधान्वयसंभवे कथमन्यतरनिर्णय इत्यत आह—तत्रेति ॥ अप्राप्ते यवागूभोजन इति । अकर्तव्यत्वेनावगते–इत्यर्थः । प्ररोचनायेति शेषः ॥ न तु तदङ्गमिति । भवैतिक्रियाकर्त्रुद्देश्यरूपं तदङ्गमित्यर्थः ॥ भाष्ये—विभाषा भवन्तीति । अत्र विभाषेत्यग्रे सर्वनामानीति शेषः ॥ भवन्ति विभाषेत्यस्य सर्वनामानीत्यादिः ॥

(विध्यनित्यत्वसाधनाधिकरणम्)

(२३६ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ विध्यनित्यत्वमनुपपन्नं प्रतिषेधसंज्ञाकरणात् ॥ * ॥

(भाष्यम्)

विधेरनित्यत्वं नोपपद्यते । शुशाव - शुशुवतुः- शुशुवुः । शिश्वाय - शिश्वियतुः - शिश्वियुः ॥

किं कारणम् ?

'प्रतिषेधसंज्ञाकरणात्' । प्रतिषेधस्येयं संज्ञा क्रियते । तेन विभाषाप्रदेशेषु प्रतिषेधस्यैव संप्रत्ययः स्यात् ॥

(प्रदीपः) विध्यनित्यत्वमिति । विकल्प इत्यर्थः । नवाशब्द एकनिपातः प्रतिषेधवाची, तस्येहोपादानादिति भावः ॥ परिहारान्तराभिधानाय तु न बहुव्रीहावित्यसंबद्धं स्यात्–इति नोक्तम् ॥

(उद्द्योतः) ननु दिक्समासेऽपि नित्यनिषेधे न बहुव्रीहाविति सामान्यसूत्रेणैव सिद्धे विभाषा दिगिति सूत्रस्य वैयर्थ्यापत्तिरत आह—परिहारान्तरेति ॥ इति सिद्धे 'विभाषा दिक्–' इत्यसंबद्धं स्यादित्यर्थः ॥

(२३७ समाधानवार्तिकम् ॥ २ ॥)

॥ * ॥ सिद्धं तु प्रसज्य प्रतिषेधात् ॥ * ॥

(भाष्यम्)

सिद्धमेतत ॥

कथम् ?

'प्रसज्य प्रतिषेधात्' । विधाय किंचिन्नवेत्युच्यते तेनोभयं भविष्यति ॥

(प्रदीपः) सिद्धं त्विति । प्रतिषेधाद्विधिरनुमास्यते, ततो विकल्पः सेत्स्यतीत्यर्थः ॥

(उद्द्योतः) ननु प्रसक्तस्य निषेधेऽभाव एव दृष्टो न तु विकल्पोऽत आह—प्रतिषेधादिति । विभाषा श्वेरित्यादौ पिद्विषयं विधिरनुमानं करिष्यते–इत्यर्थः ॥ 'निषेधानुपपत्तिकल्पितशास्त्रेण प्रसज्य-इति वार्तिकार्थ इति भावः । एवं च षोडशिग्रहणाग्रहणवदेकविषय' त्वाद्विकल्पसिद्धिरिति तात्पर्यम् ॥ तत इति । अन्यथा कल्पितं शास्त्रं व्यर्थं स्यात् । प्रक्षालनाद्धीति न्यायविरोधान्न निषेधार्थमेव तदिति भावः ॥

(२३८ आक्षेपवार्तिकम् ॥ ३ ॥)

॥ * ॥ विप्रतिषिद्धं तु ॥ * ॥

(भाष्यम्)

विप्रतिषिद्धं तु भवति । अत्र न ज्ञायते—केनाभिप्रायेण प्रसजति, केन निवृत्तिं करोतीति ॥

(प्रदीपः) विप्रतिषिद्धं त्विति । एकविषययोर्विधिप्रतिषेधयोर्विरोधादित्यर्थः ॥

(उद्द्योतः) ननु विकल्पो विरुद्धविषय एवेति किमुच्यते—विप्रतिषिद्धं त्विति, अत आह—एकेति । युगपदिति शेषः ॥ विप्रतिषेधोपपादकं भाष्यम्–अत्र नेति ॥ प्रसजति–भावमिति शेषः ॥

(२३९ समाधानवार्तिकम् ॥ ४ ॥)

॥ * ॥ न वा प्रसङ्गसामर्थ्यादन्यत्र प्रतिषेधविषयात् ॥ * ॥

(भाष्यम्)

न वा एष दोषः ॥

किं कारणम् ?

'प्रसङ्गसामर्थ्यात्' । प्रसङ्गसामर्थ्याच्च विधिर्भविष्यति—अन्यत्र प्रतिषेधविषयात् ॥ प्रतिषेधसामर्थ्याच्च प्रतिषेधो भविष्यति—अन्यत्र विधिविषयात् ॥

(प्रदीपः) न वा प्रसङ्गेति । सामर्थ्याद्विधिप्रतिषेधयोः पर्यायो भविष्यतीत्यर्थः ॥

(उद्द्योतः) प्रसज्यते इति–प्रसङ्गः=विधिः ॥ प्रतिषेधविषयादित्यस्य कालविशेषविशिष्टात्ततोऽन्यत्र–तत्रैव, कालान्तरविशिष्टे इत्यर्थः । निषेधसामर्थ्यलब्धोऽयमर्थः ॥ 'सामर्थ्यात्प्रतिषेधविषयादन्यत्र विधिः' इत्युक्ते यत्फलितं तदाह—प्रतिषेधसामर्थ्याच्चेति । इदमपि पूर्ववद्व्याख्येयम् ॥ तद्ध्वनयन्नाह—पर्याय इति ॥

(आक्षेपभाष्यम्)

तदेतत् क सिद्धं भवति—या अप्राप्ते विभाषा । या हि प्राप्ते विभाषा, कृतसामर्थ्यस्तत्र पूर्वेणैव विधिरिति कृत्वा प्रतिषेधस्यैव संप्रत्ययः स्यात् ॥

(उद्द्योतः) भाष्ये—या हि प्राप्ते इति । केवलोभयत्रविभाषारूपा वेत्यर्थः ॥ कृतसामर्थ्य इति । पूर्वेणैव-क्लृप्तशास्त्रेणैव विधिः कृतसामर्थ्यः-विहित॰विधिकल्पकनिषेधीयशक्तिक इत्यर्थः । एवं च तत्र विधिकल्पनाभावात्प्रतिषेधमात्रप्रत्ययः स्यादिति भावः ॥ एतद्भाष्यादपि सामान्यशास्त्रप्राप्तनिषेधे विकल्पं वदन्तो मीमांसकाः रास्ताः ॥

(समाधानभाष्यम्)

एतदपि सिद्धम् ॥

कथम्?

विभाषेति महती संज्ञा क्रियते । संज्ञा च नाम यतो न लघीयः ॥

कुत एतत्?

लघ्वर्थं हि संज्ञाकरणम् । तत्र महत्याः संज्ञायाः करणे एतत्प्रयोजनम्—उभयोः संज्ञा यथा स्यात्, नेति च वेति च । तत्र या तावदप्राप्ते विभाषा, तत्र प्रतिषेध्यं नास्तीति कृत्वा वेत्यनेन विकल्पो भविष्यति । या हि प्राप्ते विभाषा, तत्रोभयमुपस्थितं भवति—नेति च वेति च । तत्र नेत्यनेन प्रतिषिद्धे, वेत्यनेन विकल्पो भविष्यति ॥

(प्रदीपः) महती संज्ञेति । तेन द्वावत्र संज्ञिनौ विकल्पप्रतिषेधावित्यर्थः । यदि हि केवलः प्रतिषेधः संज्ञी स्यात्, संज्ञाकरणमनर्थकं स्यात् । विभाषाप्रदेशेषु नेत्येव ब्रूयात् । तत्र समुदायस्येयं संज्ञेति विभाषाप्रदेशेषु विकल्पप्रतिषेधावुपतिष्ठेते । अप्राप्तविभाषासु च प्राप्त्यभावात् प्रतिषेधस्याव्यापाराद्विकल्प एवोपतिष्ठते ॥

(उद्योतः) महत्याः संज्ञाया इति भाष्येण संज्ञैव न कर्तव्येति विवक्षितम्, न तु लघ्वी कर्तव्येति—इत्याह—यदि हीति ॥ समुदायस्येति । प्रत्येकधर्मावच्छिन्नस्योभयस्येत्यर्थः ॥ विकल्पप्रतिषेधाविति । प्राप्तविभाषाविषये इत्यर्थः ॥ विकल्प एवोपेति । उभयोः संज्ञाकरणेऽपि निषेधस्यान्वयायोग्यत्वाद् द्वितीयस्यैवोपस्थितिरिति भावः ॥ अत्राप्राप्तविभाषाशब्देन केवलाप्राप्तविभाषोच्यते ॥

(भाष्यम्)

एवमपि—

(२४० आक्षेपवार्तिकम् ॥ ५ ॥)

॥ * ॥ विधिप्रतिषेधयोर्युगपद्वचनानुपपत्तिः ॥ * ॥

(भाष्यम्)

विधिप्रतिषेधयोर्युगपद्वचनं नोपपद्यते । शुशाव, शुशुवतुः, शुशुवुः । शिश्वाय, शिश्वियतुः, शिश्वियुः ॥

(भाष्यम्)

किं कारणम्?

(२४१ आक्षेपसाधकवार्तिकम् ॥ ६ ॥)

॥ * ॥ भवतीति चेन्न प्रतिषेधः ॥ * ॥

(भाष्यम्)

भवतीति चेत् प्रतिषेधो न प्राप्नोति ॥

(२४२ आक्षेपसाधकवार्तिकम् ॥ ७ ॥)

॥ * ॥ नेति चेन्न विधिः ॥ * ॥

(भाष्यम्)

नेति चेद्विधिर्न सिध्यति ॥

(प्रदीपः) एवमपीति । यद्यपि विरुद्धयोरेका संज्ञा क्रियते, तथापि प्रदेशेषु युगपद्विरोधाद्भावाभावौ विधातुं न शक्येते इत्यर्थः ॥

(उद्योतः) युगपदिति । अनवगतसंज्ञिद्वयक्रमोपस्थानस्य चोद्यमेतदित्यभिप्रायः ॥ भावाभावाविति । इमावेव भाष्ये विधिप्रतिषेधशब्देनोक्तौ ॥

(२४३ समाधानवार्तिकम् ॥ ८ ॥)

॥ * ॥ सिद्धं तु पूर्वस्योत्तरेण बाधितत्वात् ॥ * ॥

(भाष्यम्)

सिद्धमेतत् ॥

कथम्?

पूर्वं विधिमुत्तरो विधिर्बाधते । इतिकरणोऽर्थनिर्देशार्थ इत्युक्तम् ॥

(प्रदीपः) सिद्धं त्विति । उभयत्रविभाषासु प्रतिषेधेन समीकृते विषये पश्चाद्विकल्पः प्रवर्तत इत्यर्थः ॥ यदि तु पूर्वं विकल्पः प्रवर्तते पश्चात्प्रतिषेधस्तदा विकल्पप्रवृत्तिरनर्थिकैव स्यात् । आनुपूर्वी च या संज्ञाविधावाश्रिता सैव प्रदेशवाक्येष्वाश्रीयते ॥ उभयत्रविभाषार्था चेयं संज्ञा, प्राप्तविभाषायामप्राप्तविभाषायां च संज्ञाकरणस्यानुपयोगात् ॥ तथाहि—प्राप्तविभाषासु पक्षे निवृत्तिः क्रियते, पक्षे तु प्रवृत्तिः स्थितैव । अप्राप्तविभाषासु च पक्षे कार्यस्य प्रवृत्तिः क्रियते, पक्षान्तरे त्वप्रवृत्तिः स्थितैवेति नास्ति तत्र संज्ञाफलम् ॥ 'विभाषा श्वेः' इत्यत्र तु यदि विधिमुखेन विभाषाश्रुतिः प्रवर्तते—पित्स्वेव संप्रसारणं विभाषा स्यात्, कित्सु यजादित्वान्नित्यमेव स्यात् । अथ प्रतिषेधमुखेन प्रवृत्तिस्तदाऽपि कित्स्वेव विकल्प इति पित्सु न स्यात् । संज्ञाकरणे तु पूर्वं प्रतिषेधे कित्सु प्रवृत्ते पश्चाद्विधिमुखेन सर्वत्र पक्षे संप्रसारणप्रवर्तनादिष्टं सिध्यति । यदा तु प्रतिलक्ष्यं भेदेन विभाषा श्वेरित्यस्य व्यापारः क्वचिद्विधिमुखेन क्वचित्प्रतिषेधमुखेन तदा संज्ञाकरणमन्तरेणापि सिध्यतीति अशिष्योऽयं योग इति वक्ष्यते—*अशिष्यो वा विदितत्वात्* इति ॥

(उद्योतः) भाष्ये—पूर्वस्योत्तरेणेति । पूर्वस्य—प्रतिषेधस्य उत्तरेण—विकल्पेन । बाधश्चात्र न निषेधप्रवृत्तिप्रतिबन्धः, किंतु तत्फलस्याभावनिष्ठसार्वकालिकत्वस्य प्रतिबन्ध इति बोध्यम् ॥ नन्वेवमपि पूर्ववाक्येन नशब्द एवादेशः स्यात्, तत्रार्थपरत्वे मानाभावादत आह—इतिकरण इति । एवं चोभयत्रापीतिशब्दान्वय इति भावः ॥ एवं चार्थद्वयसंज्ञाकरणसामर्थ्यादेव वाक्यभेदेन क्रमेणान्वय इति भावः ॥ एवं च केवलप्राप्तविभाषायामुभयत्रविभाषायां च क्रमेण निषेधविकल्पयोरुपस्थितिः, शुद्धाप्राप्तविभाषायां तु निषेधस्यान्वया-

योग्यत्वाच्छुद्धविकल्पोपस्थितिरिति तात्पर्यम् ॥ पूर्वं विकल्पाप्रवृत्तौ हेत्वन्तरमाह—आनुपूर्व्यां चेति ॥ अनुपयोगादिति । उभयगतिरिहेत्युक्तेर्लोकगृहीतविकल्पशक्त्यैव सिद्धेरिति भावः ॥ पक्षे निवृत्तिरिति । एवं च तत्र निषेधतात्पर्यकतयैव प्रवृत्तिरिति भावः ॥ अप्राप्तेति । तत्र विधितात्पर्यकतयैव प्रवृत्तिरिति भावः ॥ विरोधेनेति । तत्राप्राप्तेरिति भावः ॥ एकस्योभयत्र तात्पर्यं तु न संभवतीत्याशयः ॥ भावतात्पर्यकतालोभेन विद्धिपयतैव स्यादिति तत्त्वम् ॥ अस्योभयत्रविभाषाविषयत्वं भाष्ये विभाषा श्वेरित्यस्यैवोदाहरणदानेन बोधितम् । एवं च तदर्थमावश्यकेऽस्मिन् अन्यत्रापि स्वशास्त्रगृहीतसङ्केतेनैव बोधात् "या हि प्राप्ते विभाषा तत्रोभयमुपस्थितं" इत्याद्युक्तभाष्यविरोध इति दिक् ॥

—⁂—

(कार्यशब्दवादनिरासः)

(२४४ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ साध्वनुशासनेऽस्मिन् शास्त्रे विभाषा तस्य साधुत्वम् ॥ * ॥

(भाष्यम्)

साध्वनुशासनेऽस्मिन् शास्त्रे यस्य विभाषा क्रियते स विभाषा साधुः स्यात् । समासस्यैव हि विभाषा क्रियते, तेन समासस्यैव विभाषा साधुत्वं स्यात् ॥

(प्रदीपः) **साध्वनुशासन इति** । साधुत्वप्रतिपादनाच्छास्त्रस्य साधुत्वस्यैव प्राधान्याद्विकल्पेन संबन्धः स्यात्, न तु तदङ्गभूतानां समाससंज्ञादीनामिति भावः ॥ ततश्च विभाषा श्वेरित्यस्यायमर्थः स्यात्—विभाषा श्वयतेः साधु संप्रसारणं भवति, पक्षे त्वसाध्विति ॥

(उद्द्योतः) साधुत्वप्रतिपादनाच्छास्त्रस्येति पाठः । शास्त्रस्येति कर्तुः शेषत्वे षष्ठी ॥ क्वचित्तु साधुत्वप्रतिपादनार्थत्वादिति पाठः ॥ प्राधान्यादिति । यदिह परिनिष्ठितं तत्साध्विति अर्थापत्तिकल्प्यवाक्यस्यैव मुख्यत्वात्तेन मुख्यतया साधुत्वस्यैव विधानादित्याशयः ॥ तदङ्गभूतानामिति । तदुद्देश्यभूतानामित्यर्थः ॥ भाष्ये—यस्य विभाषा क्रियत इति । यत्सम्बन्धेन विभाषोच्यत इत्यर्थः ॥ समासस्यैव हीति । हि—यतः समासो विभाषा क्रियते—समासो विभाषेत्युच्यते, तत्र समासोद्देशेन साधुत्वविधानात्तस्यैव विकल्पः स्यादिति भावः ॥ साधुत्वं च जातिविशेषः ॥ समासप्रकरणीयविभाषाऽधिकारस्य भाष्ये प्रत्याख्यानादाह—विभाषा श्वेरिति ॥

(आक्षेपबाधकभाष्यम्)

अस्तु । यः साधुः स प्रयोक्ष्यते । असाधुर्न प्रयोक्ष्यते ॥

(प्रदीपः) **अस्तु । यः साधुरिति** । यथा भक्ष्याभक्ष्यसंनिधौ भक्ष्यमेवोपादीयते ॥

(आक्षेपसाधकभाष्यम्)

न चैव हि कदाचित् राजपुरुष इत्येतस्यामवस्थायामसाधुत्वमिष्यते ॥

(प्रदीपः) **न चैव हीति** । सर्वदा त्वस्य साधुत्वं, नोभयरूपत्वमित्यर्थः ॥

(उद्द्योतः) साधुत्वविकल्पे दूषणमाह—भाष्ये—**न चैवे**त्यादिना । तद्व्याचष्टे—**सर्वदा त्विति** । साधुत्वस्यासाधुत्वात्पुरःसरं साधूपादानं दुष्करमित्यपि बोध्यम् ॥

(भाष्यम्)

अपिच—

(२४५ आक्षेपवार्तिकम् ॥ १० ॥)

॥ * ॥ द्वैधाऽप्रतिपत्तिः ॥ * ॥

(भाष्यम्)

द्वैधं शब्दानामप्रतिपत्तिः स्यात् । इच्छामश्च—पुनर्विभाषाप्रदेशेषु द्वैधं शब्दानां प्रतिपत्तिः स्यादिति, एतच्च न सिध्यति ।

यस्य पुनः कार्याः शब्दाः, विभाषाऽसौ समासं निर्वर्तयति ॥

(प्रदीपः) **द्वैधाऽप्रतिपत्तिरिति** । साधुत्वविकल्पेन विभाषाग्रहणस्योपयुक्तत्वात् शिश्वियतुरित्यादि रूपं न सिध्यतीत्यर्थः ॥ **यस्य पुनरिति** । एवं मन्यते—व्याकरणेन शब्दा उत्पाद्यन्ते, तन्मतेन विभाषाग्रहणेनापूर्वत्वेन विधेयत्वात्संप्रसारणमेव विकल्प्यत इति द्वैधं प्रतिपत्तिः शब्दानां सिध्यतीति ॥

(उद्द्योतः) तत्र साध्वनुशासन इत्युक्त्या शब्दनित्यत्वपक्षे एवायं दोषः, न तु कार्यत्वपक्षे—इत्युक्तम् । तदुपपादकम्—यस्य पुनरित्यादिभाष्यम् ॥

(आक्षेपबाधकभाष्यम्)

यस्यापि नित्याः शब्दास्तस्याप्येष दोषो न भवति ॥

कथम् ?

न विभाषाग्रहणेन साधुत्वमभिसंबध्यते ॥

किं तर्हि ?

समाससंज्ञाऽभिसंबध्यते—समास इत्येषा संज्ञा विभाषा भवति । तद्यथा—"मेध्यः पशुर्विभाषितो मेध्योऽनड्वान् विभाषितः"—इति । नैतद्विचार्यते—अनड्वाननड्वानिति ॥

किं तर्हि ?

आलब्धव्यो नालब्धव्य इति ॥

(प्रदीपः) **यस्यापीति** । साधुत्वस्यापौरुषेयत्वादविकल्प्यत्वात्तदङ्गानामेव विकल्पः ॥ **तद्यथेति** । पशुत्वानडुत्त्वयोरविकल्प्यत्वात्क्रिया विकल्प्यते ॥ नन्वन्यत्रोक्तम्—**न च संज्ञाया**

भावाभावाविष्येते—इति । इह तूक्तम्—**संज्ञाऽभिसंबध्यते**—इति । ततश्च विरोधः ॥ नैष दोषः । इह वृत्तिवाक्ययोर्मुख्यार्थाभेदादभिन्नार्थत्वमाश्रित्योक्तम् । अन्यत्र तु व्यपेक्षैकार्थीभावभेदाद्भिन्नार्थत्वमाश्रित्यैकार्थीभावे एव संज्ञाया भावाभावौ नेष्येते इत्युक्तमित्यविरोधः ॥

(उद्योतः) प्राधान्यात्साधुत्वस्यैव विकल्पः स्यादिति यदुक्तम् तत्राह—**साधुत्वस्येति** ॥ संज्ञायाः श्रुतत्वेन, साधुत्वस्याश्रुतत्वेन, श्रुतस्य श्रुतेनैव संबन्धस्य न्याय्यत्वात्-प्रयोगासमवायिलडादिस्थले श्रुते विधेयत्वस्यावश्यकत्वाच्चेत्यपि बोध्यम् ॥ **पशुस्त्वेति** । साक्षाच्छ्रूयमाणेऽप्ययोग्यत्वाद्यदा न संबन्धस्तदा किं वक्तव्यं—अश्रूयमाणेऽयोग्ये संबन्धो नेतीत्यर्थः ॥ **अन्यत्रेति** । समर्थसूत्रे ॥ मुख्यः—प्रधानः ॥ **अभिन्नार्थत्वमिति** । एवं च तदर्थे कश्चित्साधुत्वेनान्वाख्यायमानोऽनन्वाख्यातस्य तदर्थकस्यान्यस्य निवर्तकः स्यादिति तस्यापि साधुत्वार्थं **विभाषाऽधिकार** आवश्यक इति भावः ॥ वाक्ये व्यपेक्षा परस्पराकाङ्क्षारूपा, पदार्थानामपृथगुपस्थितिविषयत्वमेकार्थीभावो वृत्तिविषयः ॥ एवं च वृत्तिवाक्ययोर्भिन्नार्थत्वान्न वाक्यानुशासनाय विभाषाग्रहणम्, किंतु वृत्तिविषये एव संज्ञाविकल्पार्थं वाच्यम् । न च वृत्तौ संज्ञायाः स इष्यते । तस्मादेकार्थीभावस्यैव मन्दमत्यनुग्रहाय स विशेषणमिति तन्नोक्ततात्पर्यमित्यविरोध इति भावः ॥ भाष्ये—**समाससंज्ञेत्यस्य** तद्विषयैकार्थीभाव इत्यर्थः ॥

(२४५ आक्षेपवार्तिकम् ॥ २ ॥)

॥ * ॥ कार्येषु युगपदन्वाचययोगपद्यम् ॥ * ॥

(भाष्यम्)

कार्येषु शब्देषु युगपदन्वाचयेन च यदुच्यते, तस्य युगपद्वचनता प्राप्नोति—"तव्यत्तव्यानीयरः" "ठक् च मण्डूकात्" इति ॥

यस्य पुनर्नित्याः शब्दाः, प्रयुक्तानामसौ साधुत्वमन्वाचष्टे ॥

(प्रदीपः) नित्यवादी कार्यपक्षे दूषणमाह—**कार्येष्विति** । युगपद्भावे युगपच्छब्दो वर्तत इति द्वन्द्वः कृतः ॥ अन्वाचयः समुच्चयोऽभिमतः, यस्य चकारेण स्वरितत्वेन वा विधानम् । यस्य कार्याः शब्दाः स प्रयोगनिरपेक्षं शब्दानन्वाचष्ट इति तव्यादीनां युगपदुत्पत्तिः प्राप्नोति ॥

(उद्योतः) ननु युगपच्छब्दस्य एककाल इत्यर्थकस्य सप्तम्यर्थवृत्तेरन्वाचयशब्देनासावृत्तेन कथं द्वन्द्व इत्यत आह—**युगपद्भाव इति** ॥ कार्येषु—शब्देषु यौगपद्यान्वाचयविषये तेषां यौगपद्यं—युगपत्प्रयोगः प्राप्नोतीति वार्तिकाक्षरार्थः ॥ भाष्ये—**युगपद्वचनतेति** । बहुव्रीहेस्तल् ॥ अन्वाचयेनेत्युक्त्वा ठक् चेति समुच्चयोदाहरणमसङ्गतमित्यत आह—**समुच्चय इति** ॥ **स्वरितत्वेन चेति** । यथा काश्यादिभ्यष्ठञ्ञिठाविति वर्तमाने वाहीकग्रामेभ्यश्चेत्यत्र ॥ नित्यशब्दवादे तु प्रयोगदृष्टानामेव शास्त्रे काल्पनिकविधेयत्वेनेष्टप्रत्ययविभागसिद्धिः । रेखागवयन्यायस्याद्यन्ताविति सूत्रे भाष्य एव वक्ष्यमाणत्वात् ॥

(आक्षेपबाधकभाष्यम्)

ननु यस्यापि कार्यास्तस्याप्येष न दोषः ॥

कथम्?

प्रत्ययः परो भवतीत्युच्यते । न चैकस्याः प्रकृतेरनेकस्य युगपत्परत्वेन संभवोऽस्ति ॥

(प्रदीपः) **न चैकस्या इति** । ननु व्यवहितेऽपि परशब्दः प्रवर्तते ॥ सत्यम् । अन्तरालस्थमनपेक्ष्यानन्तर्यमारोप्य तत्र परशब्दप्रयोगः । निर्दिष्टग्रहणं त्वानन्तर्यार्थमिति कुतो व्यवहितस्य प्रयोगः ॥ कथं तर्ह्युक्तम्—**एका प्रकृतिर्बहवश्च प्रत्ययाः** इति? तत्र यत्राकृतेरेकत्वात्तस्याश्च परत्वाद्यानन्तर्याभावादोषः । तव्यदादयस्त्वेकाकृतियुक्ता न भवन्ति ॥

(उद्योतः) **व्यवहितेऽपीति** । लोके तथा दर्शनादिति भावः ॥ **आनन्तर्यमारोप्येति** । अनेन परादिशब्दानामव्यवहित एव प्रवृत्तिः, अत एव व्यवहिताश्चेति सूत्रं सार्थकमिति भावः ॥ शास्त्रे तु सर्वथा न व्यवहिते प्रवृत्तिरित्याह—**निर्दिष्टग्रहणं त्विति** । तुश्चार्थे । छन्दसि परेऽपि परश्चेत्यादावपि उत्तराङ्गविकल्पस्मादिति परिभाषायाः प्रवृत्तेरिति भावः ॥ **कथं तर्हीति** । सरूपसूत्रे इति भावः ॥ **एकाकृतीति** । एकानुपूर्वी हि एकाकृतिरत्र ॥

(आक्षेपाभिप्रायभाष्यम्)

नापि ब्रूमः—प्रत्ययमाला प्राप्नोतीति ॥

किं तर्हि?

कर्तव्यमिति प्रयोक्तव्ये युगपद्द्वितीयस्य तृतीयस्य च प्रयोगः प्राप्नोतीति ॥

(प्रदीपः) **नापि ब्रूम इति** । एकस्याः प्रकृतेः सर्वे भवन्तीति न ब्रूमः । किं तर्हि? प्रत्ययान्तरेण प्रकृत्यन्तरस्याक्षेपात् 'कर्तव्यं' इति प्रयुयुक्षिते करणीयादीनामपि प्रयोगः प्राप्नोति ॥

(उद्योतः) भाष्ये—**नापि ब्रूम** इत्यस्य नव ब्रूम इत्यर्थः ॥

(आक्षेपबाधकभाष्यम्)

नैष दोषः । अर्थगत्यर्थः शब्दप्रयोगः । अर्थं संप्रत्याययिष्यामीति शब्दः प्रयुज्यते । तत्रैकेनोक्तत्वात्तस्यार्थस्य द्वितीयस्य च तृतीयस्य च प्रयोगेण न भवितव्यम्, "उक्तार्थानामप्रयोगः" इति ॥

(प्रदीपः) **अर्थगत्यर्थ इति** । 'तव्यत्तव्यानीयरः' इत्यस्माद्वाक्याद्वाक्यान्तराण्युपप्लवन्ते प्रतिपादकानि—धातोस्तव्यद्भवति भावकर्मणोरित्यादीनि । तत्र कर्तव्यशब्देन तस्यार्थस्य प्रतिपादितत्वात्करणीयशब्दो न प्रयुज्यते ॥

(उद्योतः) अर्थोऽपि समुदायस्य-इति शङ्कमानं प्रत्याह—**तव्यदिति** । प्रत्ययादिसंज्ञास्तव्यत्तव्यानीयर इति बहुवचननिर्देशात् प्रत्येकमिति प्रत्येकमेव भावाद्यर्थकत्वमिति भावः ॥

(२४६ आक्षेपवार्तिकम् ॥ ३ ॥)

॥ * ॥ आचार्यदेशशीलनेन च तद्विषयत्वम् ॥ * ॥

(भाष्यम्)

आचार्यशीलनेन देशशीलनेन च यदुच्यते तस्य तद्विषयता प्राप्नोति । "इको ह्रस्वोऽङ्यो गालवस्य" "प्राचामवृद्धात् फिन् बहुलम्" इति । गालवा एव हि ह्रस्वान्प्रयुञ्जीरन्, प्राक्षु चैव हि फिन् स्यात् ।

तद्यथा—"जमदग्निर्वा एतत्पञ्चममवदानमवाद्यत्, तस्मान्नाजामदग्न्यः पञ्चावत्तं जुहोति" ॥

यस्य पुनर्नित्याः शब्दाः, गालवग्रहणं तस्य पूजार्थम्, देशग्रहणं च कीर्त्यर्थम् ॥

(प्रदीपः) **आचार्येति** । आचार्यस्य देशस्य च पुनः पुनः संकीर्तनमाचार्यदेशशीलनं । तत्र तस्य शब्दस्य तद्विषयत्वमेव स्यात्, सर्वप्रयोक्तृप्रसङ्गे गालवस्यैव तत्प्रयोक्तृत्वमिति नियमार्थं स्यात् ॥ **यस्य पुनरिति** । अनादित्वाच्छब्दव्यवहारस्य नित्यत्वपक्षे नास्ति प्रयोक्तृनियमः । केवलं गालवः स्मर्तृत्वेन निर्दिष्टोऽस्य शास्त्रस्य प्रामाण्यं प्रतिपादयितुमिति पूजार्थमाचार्यग्रहणम् । शास्त्रस्य ह्यनाद्यर्थप्रतिपादकत्वात्पूजा भवति ॥ **कीर्त्यर्थमिति** । कीर्तौ सत्यां तेषां स्वर्गव्यवस्थानं स्थिरं भवति । यथा—इन्द्रद्युम्नादीनाम् ॥

(उद्द्योतः) पुनः पुनः संकीर्तनमिति । अत्र पुनःपुनरित्यस्योपयोगश्चिन्त्यः । एकैकस्मिन् शास्त्रे तदभावाच्च । तस्मात्संकीर्तनमात्रमेवात्र शीलनमिति बोध्यं, तेन यत्कार्यमुच्यते—इति वार्तिकाक्षरार्थः ॥ अत एवाग्रे भाष्ये तत्कीर्तने चेत्येवोक्तम् ॥ तद्विषयत्वमुपपादयति—**सर्वप्रयोक्त्रिति** । ईको ह्रस्वो भवति, तत्प्रयोक्तृत्वं च गालवस्येत्यादिक्रमेण सूत्रार्थः ॥ भाष्ये—प्राक्षु चैवेति । प्राग्देश एव फिन्प्रयोगः स्यादित्यर्थः ॥ अनादित्वादिति । ऐवं च गालवातिरिक्तशिष्टैरपि प्रयुज्यमानत्वान्नियमासंभवः ॥ किं चैतत्पक्षे शास्त्रं देवदत्तगवयन्यायेन कल्पितशब्दविषयमिति कल्पितशब्दे प्रयोक्तृनियमासंभव इति भावः ॥ **शास्त्रस्य प्रामाण्यमिति** । एवं च पूजार्थमित्यस्य स्वशास्त्रपूजार्थमित्यर्थ इति भावः ॥ तदेवाह—**शास्त्रस्य हीति** ॥ भाष्ये—**देशग्रहणं चेति** । चेनाचार्यग्रहणम् । देशग्रहणस्य पूजार्थत्वं तु वक्तुमशक्यम्, देशस्य स्मर्तृत्वाद्यभावादिति भावः ॥ **स्थिरं भवतीति** । ततश्च देशकीर्तौ तद्देशीयानां स्वर्गवस्थानमित्यर्थः । तेन च पाणिनेरपि तदिति भावः ॥ ननु नित्यशब्दवादे गालवादिग्रहणस्य पूजार्थत्वे ह्रस्वाभावविशिष्टस्य साधुत्वबोधनं न स्यात्, तत्पक्षे लघूपायेन साध्वसाधुविवेकाय शास्त्रमिति चेन्न । गालवः स्मर्ता नान्य इति स्मृत्यन्तरानुसन्धानद्वारेण विकल्पसिद्धेः । वाग्रहणे एव कर्तव्ये गालवग्रहणं व्यर्थमिति शङ्कानिरासार्थं तु भाष्ये पूजार्थमित्युक्तम् ॥

(आक्षेपबाधकभाष्यम्)

ननु च—यस्यापि कार्याः शब्दाः, तस्यापि गालवग्रहणं पूजार्थं स्यात्, देशग्रहणं कीर्त्यर्थम् ॥

(प्रदीपः) **ननु च यस्यापीति** । कार्यपक्षेऽपि पूजा शक्यते व्याख्यातुम्—यस्माद्गालवेन ह्रस्वत्वं प्रयुक्तं तस्मात्त्वमपि प्रयुङ्क्ष्वेति स्तुत्यर्थोऽर्थवादः स्यादित्यर्थः ॥

(२४७ आक्षेपसमर्थनवार्तिकम् ॥ ४ ॥)

॥ * ॥ तत्कीर्तने च द्वैधाऽप्रतिपत्तिः ॥ * ॥

(भाष्यम्)

तत्कीर्तने च द्वैधं शब्दानामप्रतिपत्तिः स्यात् । इष्यते चैव पुनराचार्यग्रहणेषु देशग्रहणेषु च द्वैधं शब्दानां प्रतिपत्तिः स्यादिति, तच्च न सिध्यति ॥

(प्रदीपः) इदानीं कार्यपक्षे दूषणमाह—**तत्कीर्तन इति** । कार्यपक्षेऽयमर्थः स्यात्—यस्माद्गालवेन ह्रस्वत्वं प्रयुक्तं तस्मात्प्रयोक्तव्यमिति । ततश्च ह्रस्वत्वस्य विकल्पो न स्यात् । नित्यत्वपक्षे तु गालवो ह्रस्वत्वस्मर्ता, अन्यो दीर्घस्येति स्मृत्यन्तरानुसन्धानद्वारेण विकल्पः सिध्यतीति नित्यपक्ष एव युक्तः ॥

(उद्द्योतः) भाष्ये—तत्कीर्तने चेति । आचार्यदेशकीर्तने चेत्यर्थः । यस्य कार्याः शब्दास्तस्येति शेषः ॥ तदेवाह—**इदानीमिति** ॥ **प्रयुक्तमिति** । कृतमित्यर्थः ॥ **नित्यपक्षे त्विति** । कार्यपक्षे त्वेवं वक्तुमशक्यम्—यतो गालवेन कृतोऽतः कर्तव्यः, नान्येन कृतोऽतो न कर्तव्यः—इति । अन्येन कृतस्य पुनः करणवैयर्थ्यात् । न ह्यन्यकृतस्य पुनः करणमस्ति । नाप्यन्येनाकृतस्याकरणम् । तादृशस्यैव करणात् ॥ एतेनान्येन कृतस्यानुवादोऽन्याकृतत्वबोधनद्वारा विकल्पबोधक इति परास्तम् ॥ पाणिनिकृतानामपि पचो व इत्यादीनामन्याकृतत्वेन तेषामपि विकल्पापत्तेश्च । तस्मात्कार्यवादोऽसङ्गत इति दिक् ॥

(इति कार्यशब्दवादनिरासः)

(सूत्रप्रत्याख्यानम्)

(२४८ सिद्धान्तवार्तिकम् ॥ १ ॥)

॥ * ॥ अशिष्यो वा विदितत्वात् ॥ * ॥

(भाष्यम्)

अशिष्यो वा पुनरयं योगः ॥

किं कारणम् ?

'विदितत्वात्' । यदनेन योगेन प्रार्थ्यते तस्यार्थस्य विदितत्वात् ॥ येऽपि ह्येतां संज्ञां नारभन्ते तेऽपि विभाषेत्युक्तेऽनित्यत्वमवगच्छन्ति ॥

याज्ञिकाः खल्वपि संज्ञामनारभमाणा विभाषेत्युक्तेऽनित्यत्वमवगच्छन्ति । तद्यथा—"मेध्यः पशुर्विभाषितो मेध्योऽनड्वान्विभाषितः" इति । आलब्धव्यो नालब्धव्य इति गम्यते ॥

आचार्यः खल्वपि संज्ञामारभमाणो भूयिष्ठमन्यैरपि शब्दैरेतमर्थं संप्रत्याययति—बहुलम्, अन्यतरस्याम्, उभयथा, वा, एकेषाम्—इति ॥

(प्रदीपः) **अशिष्यो वेति** । वाशब्दो विकल्पे ॥ जात्याकृतिपक्षे उभयत्र विभाषार्थं सूत्रं कर्तव्यम् । व्यक्तिपक्षे तु लक्ष्यभेदेन लक्षणभेदात्कश्चित् किंचिल्लक्षणं विधिमुखेन प्रवर्तते,

कश्चित्प्रतिषेधमुखेन प्रवर्तेत इतीष्टसिद्ध्या सूत्रं न कर्तव्यमित्यर्थः ॥

(उद्योतः) ननु लोकतोऽनित्यत्वार्थलाभेऽपि निषेधविकल्पयोरलाभ इत्यत आह—भाष्ये—**आचार्यः खल्वपीति** । एवं च ह्रक्रोरित्याद्युभयत्र विभाषायां यथा तव तयोर्लाभस्तथा विभाषापदघटितेऽपि भविष्यतीति नार्थः सूत्रेणेति भावः ॥ **वाशब्दो विकल्पे इति** । यत्तु अर्थस्य संज्ञित्ववद्विभाषापदार्थस्यैव संज्ञात्वम्, तत्रापीतेः संबन्धात् । न च पदजन्यपदार्थोपस्थित्यभावेनान्वयासंभवः, विकल्पवाचिपदस्य तदर्थे लक्षणाऽभ्युपगमात् । एवं च लक्षणातात्पर्यग्राहकमिदं सूत्रम् । अर्थे न संज्ञात्वमिति चेत्, तदर्थाक्षिप्तशब्दमात्रस्य संज्ञात्वमस्तु; इतिशब्दसंबन्धसामर्थ्यादिति । तन्न । एकस्यानेकसंज्ञायाः शास्त्रेऽदर्शनात् । **अनाकृतिः संज्ञेति** वृद्धिसूत्रस्थभाष्यविरोधाच्च ॥ **तेनाकृतीति** । तत्पक्षे लिट्त्वजातौ विधिमुखेन प्रवृत्तौ पित्येव स्यात्, निषेधमुखेन प्रवृत्तौ कित्येव स्यात्, न तु सर्वत्रेति सूत्रं कर्तव्यम् । सति च सूत्रे लिट्त्वजातौ प्राप्तस्य निषेधे तस्यामेव विकल्पो विधीयमानः सर्वत्र सिध्यतीति भावः ॥ प्रत्याख्यानाशयमाह—**व्यक्तिपक्षे त्विति** । **कश्चिद्विधिमुखेनेत्यन्वयः** ॥ **किंचिल्लक्षणं**—उभयत्रविभाषारूपम् ॥ उत्तरत्र तु **कश्चित्प्रतिषेधमुखेनेत्येव** पाठः ॥

परे तु—आकृतिपक्षे किं तज्जात्याश्रयसकलव्यक्तिविषयं लक्षणम्, उत—तज्जात्याश्रययत्किंचिद्विषयम् । नाद्यः । सूत्रारम्भेऽपि नपदघटितवाक्यस्य तद्विषयताया वक्तुमशक्यत्वात् । तस्य यत्किंचिद्विषयता, वाघटितस्य सर्वविषयतेति तु दुर्लभम् ॥ नान्त्योऽपि । न **ब्राह्मणं हन्यादि**त्यादौ जातिपक्षे सर्वव्यक्तिविषयताया एव दृष्टत्वात् । **किंच** तत्र किं विधिमुखप्रवृत्त्या पिद्विषयत्वं - निषेधमुखप्रवृत्त्या किद्विषयत्वं वा-इत्यत्र विनिगमनाविरहात्सूत्र विनाऽप्युभयमुखेन प्रवृत्ताविष्टसिद्धेः। न च भावतात्पर्यकता पिद्विषयत्वे विनिगमिका, **विभाषोपयमने** इत्यादौ त्रिसंशयत्वानुपपत्तेः । भावतात्पर्यकतालोभेनाप्राप्तविभाषात्वस्यैव संभवात् । **विप्रतिषेधशास्त्रबलात्तेष्वभावतात्पर्यकताऽपि** स्यादिति चेत्, प्रकृतेऽपि तुल्यम् । तस्मात्पक्षद्वयेऽपि सूत्रप्रत्याख्याने भाष्यतात्पर्यम् ॥ **किं च** सूत्रे कृते त्रिसंशयाप्राप्तविभाषास्वपि तत्प्रवृत्तिः स्यादिति सोच्छेद्यैतैव । लक्ष्यानुसारादप्रवृत्तौ तु सूत्रं व्यर्थमेवेति भाष्याशयः ॥ एतदेव ध्वनयन् त्रिसंशयाप्राप्तविभाषां दर्शयति । त्रिसंशयास्वप्राप्तविभाषात्वमेवेति भ्रमनिरासायेतरयोरपि कथनमित्याहुः ॥

(इति सूत्रप्रत्याख्यानम्)

(अप्राप्तविभाषाप्रकरणम्)

(२४९ अधिकारवार्तिकम् ॥ १ ॥)

॥ * ॥ अप्राप्ते त्रिसंशयाः ॥ * ॥

(भाष्यम्)

इत उत्तरं या विभाषा अनुक्रमिष्यामः, अप्राप्ते ता द्रष्टव्याः ॥ त्रिसंशयास्तु भवन्ति—प्राप्ते, अप्राप्ते, उभयत्र वेति ॥

(प्रदीपः) **अप्राप्ते इति** । अधिकारोऽयम् ॥ **त्रिसंशया इति** । त्रिष्वर्थेषु संशयो यासु ताः—त्रिसंशयाः ॥

(उद्योतः) इत उत्तरमित्यस्य लाभे युक्तिमाह—**अधिकार इति** ॥ संशयत्रयस्य क्वाप्यभावादाह—**त्रिष्विति** ॥

(१ अप्राप्तविभाषोदाहरणभाष्यवार्तिकम्)

॥ द्वन्द्वे च-विभाषा जसि ॥

(भाष्यम्)

प्राप्ते, अप्राप्ते, उभयत्र वेति संदेहः ॥

(आक्षेपभाष्यम्)

कथं वा प्राप्ते ? कथं वाऽप्राप्ते ? कथं वोभयत्र ?

(संदेहसाधकभाष्यम्)

उभयशब्दः सर्वादिषु पठ्यते । तयपश्चायजादेशः क्रियते । तेन वा नित्ये प्राप्ते, अन्यत्र वाऽप्राप्ते, उभयत्र वेति ॥

(प्रदीपः) **द्वन्द्वे चेति** । प्रकरणोपलक्षणार्थमेतदुपात्तम् । **प्रथमचरमत**येत्यत्र तयग्रहणे संशयः । तत्र तयशब्देन **प्रयोजनं सर्वनामाव्ययसंज्ञाया**मिति वा - अन्वर्थसंज्ञाविज्ञानाद्वा - केवलस्य प्रयोगाभावात्तदन्तस्यैव सर्वनामत्वसंभवात् **प्रत्ययग्रहण**परिभाषया तदन्तविधिः ॥ तत्र यदि सर्वादिग्रहणेन तयान्तं विशेष्यते, नेमशब्दोऽव्यभिचारात् प्रथमादयस्त्वसंभवात् न विशेष्यन्ते, तदोभयशब्दस्य जसि नित्या संज्ञा विभाष्यत इति प्राप्तविभाषा स्यात् ॥ अथ **सर्वादीनीति** निवृत्तम्—पूर्वविप्रतिषेधश्च, तदाऽप्राप्तविभाषा ॥ अथ परविप्रतिषेधः तदोभयत्रविभाषा ॥

(उद्योतः) द्वन्द्वे च विभाषा जसीत्युक्तोभयशब्दोदाहरणमसङ्गतमत आह—**उपलक्षणेति** । **विभाषा जसी**त्यस्य द्वन्द्वविषयतया द्वन्द्वे च संज्ञानिषेधेन सर्वनामसंज्ञीयाप्राप्तविभाषात्वनिश्चयेन—निषेधीयप्राप्तविभाषात्वनिश्चयेन—वा त्रिसंशयत्वाभावादिति भावः ॥ 'द्वन्द्वे' इत्यस्यासंबन्धे पूर्वादीनां जसि विकल्पारम्भो व्यर्थः स्यादिति तात्पर्यम् ॥ ननु तयशब्देऽपि कथं संशयः ? **प्रथमादिसूत्रेण** प्रत्ययमात्रस्य संज्ञा. **सर्वादिसूत्रेण** तु उभयशब्दस्य समुदायस्य—इति भिन्नविषयत्वेनाप्राप्तविभाषात्वनिर्णयादत आह—**तत्रेति** ॥ **तयशब्देने**त्यस्य तदन्तविधिरित्यनेनान्वयः ॥ अन्वर्थत्वेन कथं तदन्तविधिरत आह—**केवलस्येति** ॥ **सर्वनामत्वसंभवात्**—सर्वार्थबोधकत्वसंभवात् । तथा च तस्य सर्वार्थबोधकत्वाभावात्सामर्थ्येन संज्ञाविधावपि प्रत्ययग्रहणपरिभाषया तदन्तविधिरिति भावः ॥ **पूर्वविप्रतिषेधश्चेति** । सर्वादित्वनिबन्धना संज्ञा जसभिन्ने सावकाशा, द्वितयादिषु च विकल्पः, उभयशब्दे जस्युभयप्राप्तौ पूर्वविप्रतिषेधः । न च नित्या संज्ञाऽन्तरङ्गा, अन्तरङ्गपरिभाषाया अप्रवृत्तेः । तथाहि—न **'अन्तरङ्गं बलीयः'** इत्यस्या अत्र विषयः, युगपत्प्राप्त्यभावात् । अमादेः सर्वनाम्नो विहितत्वसंपत्तये तस्याः पूर्वमेव प्रवृत्तिः, अस्या जसुत्पत्त्यनन्तरमिति स्पष्टमेव ॥ नाप्यसिद्धं **बहिरङ्गमन्तरङ्गे** इत्यस्याः, अन्तरङ्गोत्तरं बहिरङ्गप्राप्तेरनया तत्प्रवृत्तेर्वारयितुमशक्यत्वात् । बहुशस्तथा सत्त्वात् । तदुत्तरमप्येतत्प्रवृत्त्या पक्षे तदभावविशिष्टस्य साधुत्वबोधनं पूर्वादिष्विव । त्रिसंशयत्वस्य भाष्योक्तस्यासङ्गत्यापत्तेश्चेति दिक् ॥ भाष्ये—**तेन वेत्यादि** । तेन नित्ये प्राप्ते वा—अन्यत्राप्राप्ते वा—इत्यन्वयः ॥

(सिद्धान्तभाष्यम्)

अप्राप्ते । अयचू प्रत्ययान्तरम् ॥

(प्रदीपः) प्रत्ययान्तरमिति । आदेशपक्षे पूर्वविप्रतिषेधो वक्तव्य इति प्रत्ययान्तरपक्ष आश्रितः ॥ 'उभादुदात्तो नित्यम्' इत्यत्र तयस्येति नानुवर्तते-इति प्रत्ययान्तरमयज् भवति ॥

(उद्द्योतः) प्रत्ययान्तरेति । एवं चोभयशब्देऽस्याप्राप्तेरप्राप्तविभाषात्वमेवेति भावः ॥

(समाधानबाधकभाष्यम्)

यदि प्रत्ययान्तरम्, उभयीति ईकारो न प्राप्नोति ॥

(समाधानसाधकभाष्यम्)

मा भूदेवम्, 'मात्रचः' इत्येवं भविष्यति ॥

कथम्?

मात्रजिति नेदं प्रत्ययग्रहणम् ॥

किं तर्हि?

प्रत्याहारग्रहणम् ॥

क्व संनिविष्टानां प्रत्याहारः?

मात्रशब्दात्प्रभृति आ अयचश्चकारात् ॥

(समाधानबाधकभाष्यम्)

यदि प्रत्याहारग्रहणम्, 'कति तिष्ठन्ति' अत्रापि प्राप्नोति ॥

(समाधानसाधकभाष्यम्)

अत इति वर्तते ॥

(समाधानबाधकभाष्यम्)

एवमपि-'तैलमात्रा-घृतमात्रा' अत्रापि प्राप्नोति ॥

(प्रदीपः) तैलमात्रेति । प्रत्याहारे सति चकारेण मात्रशब्दो न विशेषित इति 'हुयामाश्रुवसिभसिभ्यस्त्रन्' इति त्रन्नन्तादपि मात्रशब्दान्ङीप्प्रसङ्गः ॥

(उद्द्योतः) न विशेषित इति । न प्रत्याहारघटक इतरव्यावर्तकः, समुदायानुबन्धस्यावयवानुबन्धत्वाभावादिति भावः ॥

(समाधानसाधकभाष्यम्)

सदृशस्याप्यसंनिविष्टस्य न भविष्यति प्रत्याहारेण ग्रहणम् ॥

(प्रदीपः) सदृशस्यापीति । प्रमाणे वर्तमानात्प्रमेये यो मात्रज् विहितः, स प्रत्याहारेण गृह्यते-इत्यर्थः ॥

(उद्द्योतः) प्रमाणे इति । तादृशस्यैव तत्संनिवेशे सत्त्वादिति भावः ॥

(२ उदाहरणभाष्यवार्तिकम् ॥)

॥ ऊर्णोर्विभाषा ॥

(भाष्यम्)

प्राप्ते, अप्राप्ते, उभयत्र वेति संदेहः ॥

(आक्षेपभाष्यम्)

कथं वा प्राप्ते? कथं वाऽप्राप्ते? कथं वोभयत्र?

(संदेहोपपादकभाष्यम्)

"असंयोगाल्लिट् कित्" इति वा नित्ये प्राप्ते, अन्यत्र वाऽप्राप्ते, उभयत्र वेति ॥

(प्रदीपः) ऊर्णोर्विभाषेति । 'विभाषोर्णोः' इति सूत्रं यद्यसंयोगाल्लिट् किदित्यत्रानुवर्तते, ऊर्णुश्चासंयोगान्त एवेत्यसंयोगग्रहणाद्वाक्यभेदेनोर्णोः परस्येडादेर्लिटो नित्यं कित्त्वं प्राप्तं विकल्प्यते, ततः-प्राप्तविभाषा । इडुपजीवनार्थं तु स्थानान्तरे सूत्रं पठितम् ॥ अथ तत्र सूत्रं नानुवर्तते, परविप्रतिषेधश्च, ततः-अप्राप्तविभाषा ॥ अथ पूर्वविप्रतिषेधः, तदा-उभयत्रेति संशयः ॥

(उद्द्योतः) भाष्ये—ऊर्णोर्विभाषेति । ऊर्णोर्धातोः कित्त्वविषयविभाषेत्यर्थः ॥ वाक्यभेदेनेत्यस्य विकल्प्यत इत्यनेनान्वयः । इदं सर्वं ङित्त्वकित्त्वयोरैक्याभिमानेन ॥ किमर्थं तर्हि पुरस्तात्कृतमत आह—इडुपेति ॥

(सिद्धान्तभाष्यम्)

अप्राप्ते ॥

(सन्देहाक्षेपभाष्यम्)

अन्यद्धि कित्त्वम्, अन्यद्धि ङित्त्वम् ॥

(प्रदीपः) अन्यद्धीति । व्यपदेशातिदेशोऽयमिति कित्त्वङित्त्वयोर्भेदः ॥

(उद्द्योतः) शङ्कते—भाष्ये-अन्यद्धीति ॥ तद्व्याख्या—भेद इति । तथा च त्रिसंशयत्वानुपपत्तिरिति भावः ॥

(२५० संदेहसाधकवार्तिकम् ॥ २ ॥)

॥ * ॥ एकं चेन्ङित्कितौ ॥ * ॥

(भाष्यम्)

यद्येकं ङित्कितौ, ततः संदेहः ॥

(प्रदीपः) एकं चेदिति । कार्यातिदेशपक्षे गुणनिषेधस्य कार्यस्यैकत्वमनयोरित्यर्थः ॥

(उद्द्योतः) गुणनिषेधस्येति । यद्यपि ङित्कित्कार्याणि भिन्नानि बहूनि सन्ति, तथाप्यूर्णोतावन्यासंभव इति भावः ॥

(तृतीयाक्षेपभाष्यम्)

अथ हि नाना, नास्ति संदेहः ॥

(समाधानभाष्यम्)

यद्यपि नाना, एवमपि संदेहः—प्रौर्णुवि ।

(प्रदीपः) प्रौर्णुवीति । लङ उत्तमैकवचनम् ॥

(संदेहोपपादकभाष्यम्)

"सार्वधातुकमपित्" इति वा नित्ये प्राप्ते, अन्यत्र वाऽप्राप्ते, उभयत्र वेति ॥

(प्रदीपः) सार्वधातुकमपिदित्यत्र यदि विभाषोर्णोरित्येतद्वाक्यभेदेन संबध्यते, ततः-प्राप्तविभाषा ॥ अथा-

संबन्धः पूर्वविप्रतिषेधः, ततः–उभयत्र विभाषा ॥ परविप्रतिषेधे तु–अप्राप्ते ॥

(उद्द्योतः) इत्यत्रेति । इत्यत्रैवेत्यर्थः ॥ वाक्यभेदेनेति । पृथक्पाठसामर्थ्यादिति भावः ॥ परविप्रतिषेधे त्विति । सिजेः इडित्यतोऽर्थाधिकारादत्रेडागम एव गृह्यत इति पक्षे तु–इत्यपि बोध्यम् ॥

(सिद्धान्तभाष्यम्)

अप्राप्ते ॥

(३ उदाहरणभाष्यवार्तिकम्)

॥ विभाषोपयमने ॥

(भाष्यम्)

प्राप्ते, अप्राप्ते, उभयत्र वेति संदेहः ॥

(संदेहाक्षेपभाष्यम्)

कथं वा प्राप्ते? कथं वा अप्राप्ते? कथं वोभयत्र?

(संदेहोपपादकभाष्यम्)

गन्धन इति वा नित्ये प्राप्ते, अन्यत्र वाऽप्राप्ते, उभयत्र वेति ॥

(प्रदीपः) विभाषोपयमन इति । यदा गन्धनाङ्गमुपयमनं तत्र गृह्यते, तदा–प्राप्ते । पूर्वविप्रतिषेधे तु–अप्राप्ते । परविप्रतिषेधे–उभयत्रेति संदेहः ॥

(उद्द्योतः) 'यमो गन्धने' 'विभाषोपयमने' इत्येते सिचः कित्त्वविधायके ॥ यदेति । गन्धनं–सूचनम् । उपयमनं–स्वीकारः ॥ गन्धनाङ्गमिति । बहुव्रीहिः । तेन गन्धनपूर्वके स्वीकरणे यदि कित्त्वविकल्पः, ततः प्राप्तविभाषेत्यर्थः ॥

(सिद्धान्तभाष्यम्)

अप्राप्ते । गन्धन इति निवृत्तम् ॥

(उद्द्योतः) परभूतासु दीपजनेतिभिन्नासु अप्राप्तविभाषासु पूर्वविषयनिवृत्तिः पूर्वविप्रतिषेधानङ्गीकारश्चाप्राप्तविभाषात्वे बीजमिति बोध्यम् ॥

(४ उदाहरणभाष्यवार्तिकम्)

॥ अनुपसर्गाद्वा ॥

(भाष्यम्)

प्राप्ते, अप्राप्ते, उभयत्र वेति संदेहः ॥

(संदेहाक्षेपभाष्यम्)

कथं वा प्राप्ते? कथं वाऽप्राप्ते? कथं वोभयत्र?

(संदेहोपपादकभाष्यम्)

"वृत्तिसर्गतायनेषु क्रमः" इति वा नित्ये प्राप्ते, अन्यत्र वाऽप्राप्ते, उभयत्र वेति ॥

(उद्द्योतः) वृत्तिसर्गेति । आत्मनेपदविधायकम् ॥

(सिद्धान्तभाष्यम्)

अप्राप्ते । वृत्यादिष्विति निवृत्तम् ॥

(५ उदाहरणभाष्यवार्तिकम्)

॥ विभाषा वृक्षमृगादीनाम् ॥

(भाष्यम्)

प्राप्ते, अप्राप्ते, उभयत्र वेति संदेहः ॥

(संदेहाक्षेपभाष्यम्)

कथं वा प्राप्ते? कथं वाऽप्राप्ते? कथं वोभयत्र?

(संदेहोपपादकभाष्यम्)

"जातिरप्राणिनाम्" इति वा नित्ये प्राप्ते, अन्यत्र वाऽप्राप्ते, उभयत्र वेति ॥

(प्रदीपः) जातिरिति । चर्मादिमयास्तदा मृगादयो ग्राह्याः ॥

(उद्द्योतः) ननु मृगादीनां प्राणित्वादप्राणिनामिति नित्ये प्राप्त इत्ययुक्तम्, मृगादिविषये एव च त्रिसंशयत्वात्। अत आह—चर्मादीति ॥

(सिद्धान्तभाष्यम्)

अप्राप्ते । 'जातिरप्राणिनाम्' इति निवृत्तम् ॥

(प्रदीपः) निवृत्तमिति । तन्निवृत्तौ च गौणत्वाच्चर्मादिमयानामग्रहणम् ॥

(६ उदाहरणभाष्यवार्तिकम्)

॥ उषविदजागृभ्योऽन्यतरस्याम् ॥

(भाष्यम्)

प्राप्ते, अप्राप्ते, उभयत्र वेति संदेहः ॥

(संदेहाक्षेपभाष्यम्)

कथं वा प्राप्ते? कथं वाऽप्राप्ते? कथं वोभयत्र?

(संदेहोपपादकभाष्यम्)

प्रत्ययान्तादिति वा नित्ये प्राप्ते, अन्यत्र वाऽप्राप्ते, उभयत्र वेति ॥

(प्रदीपः) प्रत्ययान्तादिति वेति । कथं पुनः प्रत्ययान्ताः शब्दा रूपान्तरयुक्ता उषादिव्यपदेशं लभन्ते ॥ उच्यते— सनाद्यन्ता धातव इत्यस्य यदाऽयमर्थो व्याख्यायते—धातवः सनाद्यवयवा भवन्ति धातूनामवयवाः सनादयो भवन्ति । यथा–समासान्ताष्टजादयः, तदा पूर्वोक्तचोद्याभावः ॥

(उद्द्योतः) प्रत्ययान्ता इति । प्रत्ययः सनादिरन्तावयवो येषामित्यर्थः ॥ उषादयश्च तदेकदेशा न प्रत्ययान्तरूपा इति भावः ॥

(सिद्धान्तभाष्यम्)

अप्राप्ते । प्रत्ययान्ता धात्वन्तराणि ॥

(प्रदीपः) प्रत्ययान्ता इति । सनाद्यन्ता धातव इत्ययं योगः संज्ञासंज्ञिसंबन्धार्थ इति भावः ॥

(उद्द्योतः) संज्ञासंज्ञिसंबन्धार्थ इति । अत एव क्यजाद्यन्तानां संज्ञासिद्धिः, आवृत्तौ तु गौरवमिति भावः ॥ केचित्तु—प्रत्ययान्तादित्यनुवृत्तौ उषादिभ्यः कर्तृकिबन्तप्रकृतिकाचारक्विबन्तेभ्य

एव स्यादिति प्राप्ते विभाषा, तन्निवृत्तौ पूर्वविप्रतिषेधेऽप्राप्तविभाषा, निवृत्तौ परविप्रतिषेधे उभयत्र–इति भाष्याशयः ॥ प्रत्ययान्ता वास्त्वन्तराणीति । अस्यायं भावः—ईकन्तेभ्य आचारक्विपोऽनभिधानमेव, इतरप्रत्ययान्तास्तु नोपादय इत्यप्राप्तविभाषात्वमेवेति वदन्ति ॥

(७ उदाहरणभाष्यवार्तिकम्)

॥ दीपादीनां विभाषा ॥

(भाष्यम्)

प्राप्ते, अप्राप्ते, उभयत्र वेति संदेहः ॥

(संदेहाक्षेपभाष्यम्)

कथं वा प्राप्ते ? कथं वाऽप्राप्ते ? कथं वोभयत्र ?

(संदेहोपपादकभाष्यम्)

"भावकर्मणोः" इति वा नित्ये प्राप्ते, अन्यत्र वाऽप्राप्ते, उभयत्र वेति ॥

(प्रदीपः) भावकर्मणोरिति । चिण्भावकर्मणोरित्यत्र सूत्रे यदि दीपजनेत्येतत्सूत्रमनुवर्त्य वाक्यभेदेन संबन्धः क्रियते पृथक्पाठसामर्थ्यात्, तदा–प्राप्तविभाषा । अथ नानुवर्वते परविप्रतिषेधश्च, तदा–अप्राप्तविभाषा । पूर्वविप्रतिषेधे तूभयत्र–इति संशयः ॥

(सिद्धान्तभाष्यम्)

अप्राप्ते । कर्तरीति हि वर्तते ॥

(आक्षेपभाष्यम्)

एवमपि संदेहः—न्याय्ये वा कर्तरि, कर्मकर्तरि वेति ॥

(समाधानभाष्यम्)

नास्ति संदेहः । सकर्मकस्य कर्ता कर्मवद्भवति ॥ अकर्मकाश्च दीपादयः ॥

(प्रदीपः) अकर्मकाश्चेति । यद्यपि बुधिः सकर्मकः, तथापि एकपरिहारोपन्यासार्थमविशेषेणैतदुक्तम् ॥

(उद्द्योतः) एकपरिहारः–कर्मस्थभावकत्वाभावरूपः ॥ ननु 'कर्तरि' इत्यनुवृत्तिर्व्यर्था, कर्मणि भावे कर्मकर्तरि च परत्वाच्चिण्भावकर्मणोरित्यस्य प्रवृत्तेरिति चेन्न । विप्रतिषेधलभ्यार्थस्यैव स्फुटत्वाय अनुवृत्त्या प्रदर्शनात् इति दिक् ॥

(समाधानबाधकभाष्यम्)

अकर्मका अपि वै सोपसर्गाः सकर्मका भवन्ति ॥

(प्रदीपः) सोपसर्गा इति । अर्थान्तरवृत्तित्वादनुभवतिवदिति भावः ।

(समाधानसाधकभाष्यम्)

कर्मोपदिष्टा विधयः कर्मस्थभावकानां कर्मस्थक्रियाणां च भवन्ति । कर्तृस्थभावकाश्च दीपादयः ॥

(प्रदीपः) कर्तृस्थभावकाश्चेति । अचः कर्तृयकीत्यत्र जायते स्वयमेवेत्युदाहृतं, तस्य ण्यर्थवृत्तित्वात्कर्मस्थभावकत्वमिति नास्ति तेनास्य विरोधः ॥

(८ उदाहरणभाष्यवार्तिकम्)

॥ विभाषाऽग्रेप्रथमपूर्वेषु ॥

(भाष्यम्)

प्राप्ते, अप्राप्ते, उभयत्र वेति संदेहः ॥

(संदेहाक्षेपभाष्यम्)

कथं वा प्राप्ते ? कथं वाऽप्राप्ते ? कथं वोभयत्र ?

(संदेहोपपादकभाष्यम्)

'आभीक्ष्ण्ये' इति वा नित्ये प्राप्ते, अन्यत्र वाऽप्राप्ते, उभयत्र वेति ॥

(सिद्धान्तभाष्यम्)

अप्राप्ते । 'आभीक्ष्ण्ये' इति निवृत्तम् ॥

(प्रदीपः) आभीक्ष्ण्य इति निवृत्तमिति । पूर्वविप्रतिषेधश्चेति भावः ॥

(९ उदाहरणभाष्यवार्तिकम्)

॥ तृन्नादीनां विभाषा ॥

(भाष्यम्)

प्राप्ते, अप्राप्ते, उभयत्र वेति संदेहः ॥

(संदेहाक्षेपभाष्यम्)

कथं वा प्राप्ते ? कथं वाऽप्राप्ते ? कथं वोभयत्र ?

(संदेहोपपादकभाष्यम्)

'आक्रोशे' इति वा नित्ये प्राप्ते, अन्यत्र वाऽप्राप्ते, उभयत्र वेति ॥

(प्रदीपः) तृन्नादीनामिति । आक्रोश इत्यत्र चशब्दौ नानुवर्तेते, ततोऽयं संशयः ॥

(उद्द्योतः) तृन्नादीनामिति । 'आक्रोशे च संज्ञायाम्' विभाषा तृन्नन्नतीक्ष्णशुचिष्विति सूत्रे इत्यर्थः ॥ चशब्दकाविति । अच्कावशक्तावित्यतः । तदनुवृत्तौ तु निःसन्देहमप्राप्तविभाषेति भावः ॥ एतद्भाष्यविरोधाच्च तत्राच्काविलनुवृत्तिपरा ग्रन्था अयुक्ता एवेति तात्पर्यम् ॥

(सिद्धान्तभाष्यम्)

अप्राप्ते । 'आक्रोशे' इति निवृत्तम् ॥

(१० उदाहरणभाष्यवार्तिकम्)

॥ एकहलादौ पूरयितव्येऽन्यतरस्याम् ॥

(भाष्यम्)

प्राप्ते, अप्राप्ते, उभयत्र वेति संदेहः ॥

(संदेहाक्षेपभाष्यम्)

कथं वा प्राप्ते ? कथं वाऽप्राप्ते ? कथं वोभयत्र ? ॥

(संदेहोपपादकभाष्यम्)

"उदकस्योदः संज्ञायाम्" इति वा नित्ये प्राप्ते,

अन्यत्र वा अप्राप्ते, उभयत्र वेति ॥

(प्रदीपः) एकहलादाविति । पूरयितव्यस्यास्ति संज्ञा-उदपानमिति ॥

(सिद्धान्तभाष्यम्)

अप्राप्ते । संज्ञायामिति निवृत्तम् ॥

(११ उदाहरणभाष्यवार्तिकम्)

॥ श्वादेरिञि, पदान्तस्यान्यतरस्याम् ॥

(भाष्यम्)

प्राप्ते, अप्राप्ते, उभयत्र वेति संदेहः ।

(संदेहाक्षेपभाष्यम्)

कथं वा प्राप्ते? कथं वाऽप्राप्ते? कथं वोभयत्र?

(संदेहोपपादकभाष्यम्)

इञीति वा नित्ये प्राप्ते, अन्यत्र वाऽप्राप्ते, उभयत्र वेति ॥

(सिद्धान्तभाष्यम्)

अप्राप्ते । इञीति निवृत्तम् ॥

(१२ उदाहरणभाष्यवार्तिकम्)

॥ सपूर्वायाः प्रथमाया विभाषा ॥

(भाष्यम्)

प्राप्ते, अप्राप्ते, उभयत्र वेति संदेहः ॥

(संदेहाक्षेपभाष्यम्)

कथं वा प्राप्ते? कथं वाऽप्राप्ते? कथं वोभयत्र?

(संदेहोपपादकभाष्यम्)

चादिभिर्योग इति वा नित्ये प्राप्ते, अन्यत्र वाऽप्राप्ते, उभयत्र वेति ॥

(प्रदीपः) चादिभिरिति । प्रतिषेधस्याप्राप्तविभाषा स्थाप्यते, विधेस्तु प्राप्तविभाषैव ॥

(सिद्धान्तभाष्यम्)

अप्राप्ते । चादिभिर्योग इति निवृत्तम् ॥

(१३ उदाहरणभाष्यवार्तिकम्)

॥ ग्रो यङ्यचि विभाषा ॥

(भाष्यम्)

प्राप्ते, अप्राप्ते, उभयत्र वेति संदेहः ॥

(संदेहाक्षेपभाष्यम्)

कथं वा प्राप्ते? कथं वाऽप्राप्ते? कथं वोभयत्र?

(संदेहोपपादकभाष्यम्)

यङीति वा नित्ये प्राप्ते, अन्यत्र वाऽप्राप्ते, उभयत्र वेति ॥

(प्रदीपः) यङीति वेति । यङ्लुकि कृतेऽजादिः परः संभवति— जेगिल इति । अत्र च पचाद्यचि यङोऽचि चेति यङ्लुक् ॥

(उद्योतः) यङ्लुकीति । अचि विभाषेत्यत्र यङीति वर्तते । तत्रोभयोर्यङजाद्योरव्यवहितपरत्वासंभवाद् श्रुतसाचीत्यस्य परविशेषणत्वम्, यङीति विषयसप्तमी । अचि परे यङ्विषये रेफस्य लत्वमित्यर्थः ॥ तत्र विभाषारम्भसामर्थ्याद् यङ्लुकः पूर्वं ग्रो यङीति न भवति । न लुमतेति निषेधानित्यत्वेन पृथगल्लोपेन स्थानिवद्भावेन वा यङ्विषय इति प्राप्तविभाषात्वोपपत्तिः ॥ यङीत्येतन्निवृत्तौ विभाषाया असिद्धत्वादेव नित्यं लत्वम् । समुदायलुक्यपि न लुमतेति निषेधाच्च तस्मासिरित्यप्राप्तविभाषात्वोपपत्तिः ॥ उभयत्रविभाषात्वे त्वियमुपपत्तिः—ग्रो यङीत्येतत्प्रति प्रकरणे प्रकरणमसिद्धमिति विभाषाया असिद्धत्वाभावः । लुकः पूर्वं यङीत्यस्य न प्रवृत्तिः, अन्तरङ्गानपीति न्यायेन लुकस्तत्प्रयोजकाच्प्रत्ययस्य च पूर्वं प्रवृत्तेः ॥ न च लुकि न लुमतेति निषेधे यङ्परत्वाभावाद् ग्रो यङीत्यस्याप्राप्तेः कथमुभयत्रविभाषात्वमिति वाच्यम् । दत्तोत्तरत्वादिति दिक् ॥

(सिद्धान्तभाष्यम्)

अप्राप्ते । यङीति निवृत्तम् ॥

(इत्यप्राप्तविभाषा)

(प्राप्तविभाषाप्रकरणम्)

(२५१ अधिकारवार्तिकम् ॥ ८ ॥)

॥ * ॥ प्राप्ते च ॥ * ॥

(भाष्यम्)

इत उत्तरं या विभाषा अनुक्रमिष्यामः प्राप्ते ता द्रष्टव्याः । त्रिसंशयास्तु भवन्ति—प्राप्ते, अप्राप्ते, उभयत्र वेति ॥

(प्रदीपः) प्राप्ते चेति । प्रकृतानुवृत्त्या प्राप्तविभाषा व्यवतिष्ठते ॥

(१ उदाहरणभाष्यवार्तिकम्)

॥ विभाषा विप्रलापे ॥

(भाष्यम्)

प्राप्ते, अप्राप्ते, उभयत्र वेति संदेहः ॥

(संदेहाक्षेपभाष्यम्)

कथं वा प्राप्ते? कथं वाऽप्राप्ते? कथं वोभयत्र?

(संदेहोपपादकभाष्यम्)

'व्यक्तवाचाम्' इति वा नित्ये प्राप्ते, अन्यत्र वाऽप्राप्ते, उभयत्र वेति ॥

(प्रदीपः) अन्यत्र वेति । विप्रवदन्ति शकुनय इत्यत्र पूर्वविप्रतिषेधश्च यङीति भावः ॥

(सिद्धान्तभाष्यम्)

प्राप्ते । व्यक्तवाचामिति हि वर्तते ॥

(२ उदाहरणभाष्यवार्तिकम्)

॥ विभाषोपपदेन प्रतीयमाने ॥

(भाष्यम्)

प्राप्ते, अप्राप्ते, उभयत्र वेति संदेहः ॥

(संदेहाक्षेपभाष्यम्)

कथं च प्राप्ते? कथं चाप्राप्ते? कथं चोभयत्र?

(संदेहोपपादकभाष्यम्)

"स्वरितञितः" इति वा नित्ये प्राप्ते, अन्यत्र वाऽप्राप्ते, उभयत्र वेति ॥

(सिद्धान्तभाष्यम्)

प्राप्ते । 'स्वरितञितः' इति हि वर्तते ॥

(प्रदीपः) विभाषोपपदेनेति । कर्त्रभिप्राये क्रियाफले विषये आत्मनेपदं भवति–इत्येवं प्राप्तविभाषा व्यवतिष्ठते ॥ अथ तु तदर्थद्योतनायात्मनेपदं क्रियते, तदोपपदेनैव द्योतितत्वादप्राप्तविभाषा स्यात् ॥

(उद्द्योतः) अथ त्विति । तथा च स पक्ष पतञ्जलिभाष्यविरुद्ध इति भावः ॥ वस्तुतो द्योतकत्वपक्षेऽपि 'व्यतिलुनीते-गार्ग्यायणी' इत्यादौ द्योतकसमुच्चयस्य 'द्यौ' इत्यादौ द्योतकवाचकसमुच्चयस्य च दृष्टत्वेनात्राप्यात्मनेपदप्राप्तिरस्तीति प्राप्तविभाषा सूपपादेति चिन्त्यमेतत् ॥

(३ उदाहरणभाष्यवार्तिकम्)

॥ तिरोऽन्तर्धौ, विभाषा कृञि ॥

(भाष्यम्)

प्राप्ते, अप्राप्ते, उभयत्र वेति संदेहः ॥

(संदेहाक्षेपभाष्यम्)

कथं वा प्राप्ते? कथं वाऽप्राप्ते,? कथं वोभयत्र?

(संदेहोपपादकभाष्यम्)

"अन्तर्धौ" इति नित्ये प्राप्ते, अन्यत्र वाऽप्राप्ते, उभयत्र वेति ॥

(सिद्धान्तभाष्यम्)

प्राप्ते । 'अन्तर्धौ' इति हि वर्तते ॥

(४ उदाहरणभाष्यवार्तिकम्)

॥ अधिरीश्वरे, विभाषा कृञि ॥

(भाष्यम्)

प्राप्ते, अप्राप्ते, उभयत्र वेति संदेहः ॥

(संदेहाक्षेपभाष्यम्)

कथं वा प्राप्ते? कथं वाऽप्राप्ते? कथं वोभयत्र?

(संदेहोपपादकभाष्यम्)

'ईश्वरे' इति वा नित्ये प्राप्ते, अन्यत्र वाऽप्राप्ते, उभयत्र वेति ॥

(सिद्धान्तभाष्यम्)

प्राप्ते । 'अधिरीश्वरे' इति हि वर्तते ॥

(५ उदाहरणभाष्यवार्तिकम्)

॥ दिवस्तदर्थस्य, विभाषोपसर्गे ॥

(भाष्यम्)

प्राप्ते, अप्राप्ते, उभयत्र वेति संदेहः ॥

(संदेहाक्षेपभाष्यम्)

कथं वा प्राप्ते? कथं वाऽप्राप्ते? कथं वोभयत्र?

(संदेहोपपादकभाष्यम्)

तदर्थस्येति वा नित्ये प्राप्ते, अन्यत्र वाऽप्राप्ते, उभयत्र वेति ॥

(सिद्धान्तभाष्यम्)

प्राप्ते । 'तदर्थस्य' इति हि वर्तते ॥

(इति प्राप्तविभाषा)

(उभयत्रविभाषाप्रकरणम्)

(२५२ अधिकारवार्तिकम् ॥ ३ ॥)

॥ * ॥ उभयत्र ॥ * ॥

(भाष्यम्)

इत उत्तरं या विभाषा अनुक्रमिष्यामः, उभयत्र ता द्रष्टव्याः । निःसंशयास्तु भवन्ति—प्राप्ते, अप्राप्ते, उभयत्र वेति ॥

(१ उदाहरणभाष्यवार्तिकम्)

॥ हृक्रोरन्यतरस्याम् ॥

(भाष्यम्)

प्राप्ते, अप्राप्ते, उभयत्र वेति संदेहः ॥

(संदेहाक्षेपभाष्यम्)

कथं वा प्राप्ते? कथं वाऽप्राप्ते? कथं वोभयत्र?

(संदेहोपपादकभाष्यम्)

"गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ" इति वा नित्ये प्राप्ते, अन्यत्र वाऽप्राप्ते, उभयत्र वेति ॥

(उद्द्योतः) भाष्ये-गतिबुद्धीति नित्ये प्राप्ते इति । नियमशास्त्राणां विधिमुखेन प्रवृत्तिरिति भावः ॥

(सिद्धान्तभाष्यम्)

उभयत्र ॥

प्राप्ते तावत्—अभ्यवहारयति सैन्धवान्, अभ्यवहारयति सैन्धवैः । विकारयति सैन्धवान्, विकारयति सैन्धवैः ॥

अप्राप्ते—हरति भारं देवदत्तः, हारयति भारं देवदत्तम्, हारयति भारं देवदत्तेन । करोति कटं देवदत्तः, कारयति कटं देवदत्तम्, कारयति कटं देवदत्तेन ॥

(प्रदीपः) गतिबुद्धीति । तत्र विपूर्वो हरतिर्गत्यर्थः, अभ्यवपूर्वः प्रत्यवसानार्थः । करोतिः क्वचिदकर्मकः, यथा—विकुर्वते सैन्धवा इति ॥

(उद्योतः) तत्र विपूर्व इति । 'विहरति ग्रामं' इत्यादौ गच्छतीत्यर्थावगमादिति भावः ॥ भाष्ये—अप्राप्ते हरति भारमिति । ननु गत्यर्थत्वादस्यापि प्राप्तिरस्त्येवेति चेन्न । प्रापणार्थत्वेऽपि गत्यर्थत्वाभावस्य न गतीति सूत्रे वक्ष्यमाणत्वात् ॥

(२ उदाहरणभाष्यवार्तिकम्)

॥ न यदि, विभाषा साकाङ्क्षे ॥

(भाष्यम्)

प्राप्ते, अप्राप्ते, उभयत्र वेति संदेहः ॥

(संदेहाक्षेपभाष्यम्)

कथं वा प्राप्ते ? कथं वाऽप्राप्ते ? कथं वोभयत्र ?

(संदेहोपपादकभाष्यम्)

यदीति वा नित्ये प्राप्ते, अन्यत्र वाऽप्राप्ते, उभयत्र वेति ॥

(प्रदीपः) यदीति वेति । प्रतिषेधे प्राप्ते इत्यर्थः । लट् तु यदि प्रतिषिद्धः ॥

(सिद्धान्तभाष्यम्)

उभयत्र ॥

प्राप्ते तावत्—अभिजानासि देवदत्त यत्कश्मीरेषु वत्स्यामः, यत्कश्मीरेष्ववसाम । यत्तत्रौदनं भोक्ष्यामहे, यत्तत्रौदनमभुञ्ज्महि ॥

अप्राप्ते—अभिजानासि देवदत्त कश्मीरान् गमिष्यामः, कश्मीरानगच्छाम । तत्रौदनं भोक्ष्यामहे, तत्रौदनमभुञ्ज्महि ॥

(३ उदाहरणभाष्यवार्तिकम्)

॥ विभाषा श्वेः ॥

(भाष्यम्)

प्राप्ते, अप्राप्ते, उभयत्र वेति संदेहः ॥

(संदेहाक्षेपभाष्यम्)

कथं वा प्राप्ते ? कथं वाऽप्राप्ते ? कथं वोभयत्र ?

(संदेहोपपादकभाष्यम्)

कितीति वा नित्ये प्राप्ते, अन्यत्र वाऽप्राप्ते, उभयत्र वेति ॥

(सिद्धान्तभाष्यम्)

उभयत्र ॥

प्राप्ते तावत्—शुशुवतुः शुशुवुः, शिश्वियतुः शिश्वियुः ॥

अप्राप्ते-शुशाव-शुशविथ, शिश्वाय-शिश्वयिथ ॥

(४ उदाहरणभाष्यवार्तिकम्)

॥ विभाषा संघुषास्वनाम् ॥

(भाष्यम्)

संपूर्वाद्घुषेः—

प्राप्ते, अप्राप्ते, उभयत्र वेति संदेहः ॥

(संदेहाक्षेपभाष्यम्)

कथं वा प्राप्ते ? कथं वाऽप्राप्ते ? कथं वोभयत्र ?

(संदेहोपपादकभाष्यम्)

"घुषिरविशब्दने" इति वा नित्ये प्राप्ते, अन्यत्र वाऽप्राप्ते, उभयत्र वेति ॥

(सिद्धान्तभाष्यम्)

उभयत्र ॥

प्राप्ते तावत्—संघुष्टा रज्जुः, संघुषिता रज्जुः ।

अप्राप्ते-संघुष्टं वाक्यमाह, संघुषितं वाक्यमाह ॥

(आस्वनोदाहरणभाष्यम्)

आङ्पूर्वात्स्वनेः–

प्राप्ते, अप्राप्ते, उभयत्र वेति संदेहः ॥

(संदेहाक्षेपभाष्यम्)

कथं वा प्राप्ते ? कथं वाऽप्राप्ते ? कथं वोभयत्र ?

(संदेहोपपादकभाष्यम्)

मनसीति वा नित्ये प्राप्ते, अन्यत्र वा अप्राप्ते, उभयत्र वेति ॥

(सिद्धान्तभाष्यम्)

उभयत्र ॥

प्राप्ते तावत्—आस्वान्तं मनः, आस्वनितं मनः ।

अप्राप्ते—आस्वान्तो देवदत्तः, आस्वनितो देवदत्त इति ॥

इति श्रीमद्भगवत्पतञ्जलिविरचिते व्याकरणमहाभाष्ये प्रथमस्याध्यायस्य प्रथमे पादे षष्ठमाह्निकम् ॥

(प्रदीपः) दैवयज्ञीत्यादि न विचारितम्, तस्मादिङ्मात्रप्रदर्शनार्थं कृतम् ॥ ४४ ॥

इत्युपाध्यायजैयटपुत्रकैयटकृते महाभाष्यप्रदीपे प्रथमस्याध्यायस्य प्रथमे पादे षष्ठमाह्निकम् ॥

(उद्योतः) दैवयज्ञीत्यादीति । अनार्षयोरित्यनुवृत्त्यादिनाऽत्रापि सन्देहसंभव इति भावः ॥ आदिना विभाषा घुषे इति ॥ ४४ ॥

इति श्रीशिवभट्टसुतसतीगर्भजनागोजीभट्टकृते भाष्यप्रदीपोद्द्योते प्रथमाध्यायस्य प्रथमे पादे षष्ठमाह्निकम् ॥

अथ प्रथमाध्यायस्य प्रथमपादे सप्तममाह्निकम् ॥

(४० संप्रसारणसंज्ञासूत्रम् ॥ १ । १ । ७ आ. १)

इग्यणः संप्रसारणम् ॥ १ । १ । ४५ ॥

(उभयसंज्ञात्वस्थापनाधिकरणम्)

(आक्षेपभाष्यम्)

किमियं वाक्यस्य संप्रसारणसंज्ञा क्रियते—इग्यण इत्येतद्वाक्यं संप्रसारणसंज्ञं भवतीति । आहोस्विद्वर्णस्य—इग्यो यणः स्थाने वर्णः स संप्रसारणसंज्ञो भवतीति ॥

कश्चात्र विशेषः ?

(प्रदीपः) **इग्यणः संप्रसारणम् ॥ ४५ ॥** पक्षद्वयस्यापि लिङ्गदर्शनाद्युगपच्चोभयोः संज्ञित्वस्यैकस्मिन्वाक्येऽनुपपादादेकतरपक्षाश्रयणे सर्वकार्यासिद्धिप्रसङ्गात् **प्रश्नः—किमियमिति ।** वाक्यशब्देन वाक्यार्थ उच्यते । इग्यण इत्यत्र भवतीत्यध्याहारा**दिग्यणो भवतीति** योऽयं वाक्यार्थस्तस्येयं संज्ञेत्यर्थः । अथवा वाक्यस्यैवेयं संज्ञा । तत्प्रतिपादितं च वाक्यं स्वार्थं प्रतिपादयति ॥ यणः स्थाने य इग्वर्णः स संप्रसारणसंज्ञ इति **वर्णसंज्ञापक्षः ॥**

(उद्योतः) **इग्यणः० ॥ ४५ ॥ लिङ्गेति ।** प्रदेशेषु प्रथमानिर्देशो वाक्यसंज्ञायाः, अन्यविभक्तिनिर्देशश्च वर्णसंज्ञाया लिङ्गमिति भावः ॥ ननु तर्हि लिङ्गादुभयोरपि संज्ञित्वमस्त्वित्यत आह—**युगपच्चेति ।** अनेकस्यार्थस्यैकशब्देन युगपदनुपस्थितेरिति भावः ॥ ननु वाक्यस्य संज्ञायां प्रदेशेषु तस्यैव विधानं स्यादत आह—**वाक्यार्थ इति ।** पूर्वसूत्रात् 'इति' इत्यनुवर्त्य इग्यण इति संप्रसारणसंज्ञमित्यर्थादिति भावः ॥ स्वं रूपमित्युक्तेः शास्त्रे शब्दपरत्वस्यौत्सर्गिकत्वेन 'इति'समभिव्याहारं विनाऽर्थपरत्वासंभवादिति बोध्यम् ॥ ननु यणस्थानिकत्वोपलक्षित इगेव वाक्यार्थ इति वर्णपक्षादस्य को भेद इत्यत आह—**भवतीति ।** एवंचेग्भवनं वाक्यार्थ इति भावः ॥ **तत्प्रतिपादितमिति ।** संज्ञयोपस्थितस्यानर्थकत्वे तदर्थानुपयोगे वा संज्ञोपस्थितस्वरूपस्यैवोपादानम् । न चैतदुभयमप्यत्रेति भावः ॥ **प्रतिपादयतीति ।** ष्यङः संप्रसारणमित्यादौ ॥ उच्चारितस्यैव प्रत्यायकत्वमित्युदितिदिति सूत्रस्थभाष्यविरुद्धमिदम् ॥

(२५३ वाक्यसंज्ञापक्षदूषणवार्तिकम् ॥ १ ॥)

॥ * ॥ संप्रसारणसंज्ञायां वाक्यस्य संज्ञा चेद्वर्णविधिः ॥ * ॥

(भाष्यम्)

संप्रसारणसंज्ञायां वाक्यस्य संज्ञा चेद्वर्णविधिर्न सिध्यति—संप्रसारणात्परः पूर्वो भवतीति, संप्रसारणस्य दीर्घो भवतीति । न हि वाक्यस्य संप्रसारणसंज्ञायामेष निर्देश उपपद्यते । नाप्येतयोः कार्ययोः संभवोऽस्ति ॥

(प्रदीपः) **वर्णविधिरिति ।** वर्णाश्रयो विधिर्दीर्घादिः ॥ **न हीति ।** वाक्यार्थेन पौर्वापर्याभावात्, तस्य चासत्त्वभूतस्य स्थानित्वासंभवादित्यर्थः ॥

(उद्योतः) **वर्णविधिरित्यस्य** वर्णविषयविधानमित्यर्थे असिद्धेरभावादाह—**वर्णाश्रय इति ।** संबन्धसामान्यषष्ठ्या समासः ॥ विधिरिति कर्मणि किरिति भावः ॥ **आदिना—एकादेशः ॥ वाक्यार्थेनेति ।** क्रियारूपेणेत्यर्थः ॥ **नाप्येतयोरिति** भाष्यं व्याचष्टे—**तस्य चेति ।** चोऽसंभवादित्युत्तरं योज्यः ॥ भाष्ये—**एतयोः कार्ययोरिति ।** पूर्वरूपदीर्घयोरित्यर्थः ॥

(द्वितीयपक्षाभ्युपगमभाष्यम्)

अस्तु तर्हि वर्णस्य ॥

(२५४ वर्णसंज्ञापक्षदूषणवार्तिकम् ॥ २ ॥)

॥ * ॥ वर्णसंज्ञा चेन्निर्वृत्तिः ॥ * ॥

(भाष्यम्)

वर्णसंज्ञा चेन्निर्वृत्तिर्न सिध्यति—'ष्यङः संप्रसारणम्' इति । स एव हि तावदिह दुर्लभः, यस्य संज्ञा क्रियते ॥

अथापि कथंचिल्लभ्येत, केनासौ यणः स्थाने स्यात् ?

अनेन ह्यसौ व्यवस्थाप्यते । तदेतदितरेतराश्रयं भवति । इतरेतराश्रयाणि च कार्याणि न प्रकल्पन्ते ॥

(प्रदीपः) **दुर्लभ इति ।** कार्यपक्षे न लभ्यते, नित्यपक्षे तु लभ्यत इति दुर्लभत्वमुक्तम् ॥ **केनासाविति ।** लोके इगेव नित्यं प्रयोगेऽस्ति, तस्य तु यणस्थानिकत्वं शास्त्रसमाधिगम्यमित्यर्थः ॥ भाविसंज्ञाविज्ञानं तु परिहारान्तराभिधानाय न तावदत्रोक्तम् ॥

(उद्योतः) **स एव तावन्नास्तीति** भक्तव्ये दुर्लभत्वोक्तिरनुचितेत्यत आह—**कार्यपक्षे इति ।** अनेन भाष्येणातीतानागतयोर्विद्यमानयोरप्रत्यासत्त्या शक्तिग्रहदौर्लभ्यमुक्तम् । निरूपितं चेदं मञ्जूषायां नामार्थवादे ॥ **नित्यपक्षे त्विति ।** अनेनाथापि कथंचिदित्यपि भाष्यं व्याख्यातम् ॥ **शास्त्रेति ।** 'सितं' इत्यादौ यणस्थानिकत्वाभावेन शास्त्रमात्रैकगम्यं तदित्यर्थः । शास्त्रगम्यत्वे चेतरेतराश्रयमेवेति भावः ॥ भाष्ये—**केनासाविति ।** केन मानेन 'यणः स्थाने' इति ज्ञातः स्यात् ॥ **अनेन—**संप्रसारणसंज्ञाविधायकेन शास्त्रेण असौ-इक् यणः स्थाने स्थाप्यत इत्यर्थः ॥

(२५५ समाधानवार्तिकम् ॥ ३ ॥)

॥ * ॥ विभक्तिविशेषनिर्देशस्तु ज्ञापक उभयसंज्ञात्वस्य ॥ * ॥

(भाष्यम्)

यदयं विभक्तिविशेषैर्निर्देशं करोति-संप्रसारणात्परः पूर्वो भवति, संप्रसारणस्य दीर्घो भवति, ष्यङः संप्रसारणं भवति-इति । तेन ज्ञायते—उभयोः संज्ञा भवतीति ॥

यत्तावदाह—संप्रसारणात्परः पूर्वो भवति, संप्रसारणस्य दीर्घो भवति-इति । तेन ज्ञायते—वर्णस्य भवतीति ॥

यदप्याह—ष्यङः संप्रसारणमिति । तेन ज्ञायते-वाक्यस्य संज्ञा भवतीति ॥

(प्रदीपः) उभयसंज्ञात्वस्येति । उभयोः संज्ञा—उभयसंज्ञा, तस्या भावः—उभयसंज्ञात्वम् । तत्रै तन्त्रावृत्त्येकशेषाणामन्यतमाश्रयेणोभयोः संज्ञा सिध्यति ॥

(उद्योतः) उभयोः संज्ञात्वमित्यर्थोऽसंभवी, एकस्यैव संज्ञात्वादत आह—उभयोः संज्ञेति ॥ ऐकशेषश्च प्रतिपदम् । अनेकमर्थमुद्दिश्यैकस्याः संज्ञाया एकवाक्यतयैव विधातुं शक्यत्वादत्रावृत्तेः क्व उपयोग इति चिन्त्यम् ॥

(प्रथमपक्षाभ्युपगमभाष्यम्)

अथवा पुनरस्तु वाक्यस्यैव ॥

(उक्ताक्षेपस्मारणभाष्यम्)

ननु चोक्तम्—*संप्रसारणसंज्ञायां वाक्यस्य संज्ञा चेद्वर्णविधिः* इति ॥

(समाधानभाष्यम्)

नैष दोषः । यथा काकाज्जातः काकः श्येनाज्जातः श्येनः, एवं संप्रसारणाज्जातं संप्रसारणमिति । यत्तत्सम्प्रसारणाज्जातं सम्प्रसारणमिति तस्मात्परः पूर्वो भवति, तस्य दीर्घो भवतीति ॥

(प्रदीपः) यथा काकादिति । ननु काकत्वाभिसंबन्धात्काकः । अन्यत्र चोक्तम्—येनैव हेतुनैकः काकस्तेनैवापरोऽपीति । नैष दोषः । यदाऽनुपजातजात्यभिव्यञ्जकसंस्थानविशेषः काको भवति निर्ज्ञातं च तस्य काकजन्म भवति, तदैतदुक्तम् । एवमिहापि संप्रसारणाज्जातत्वादुपचाराद्वर्णोऽपि ताच्छब्द्यं लभते-इति भावः ॥

(उद्योतः) भाष्ये—यथा काकादिति । अज्ञात एव काकत्वे तज्जातत्वमात्रेण तथा व्यवहारवदत्रापीत्यर्थः ॥ तत्र शङ्कते—नन्विति ॥ अन्यत्र-'एको गोत्रे' इत्यत्र ॥ यदाऽनुपेति । न उपजातो जात्यभिव्यञ्जकः संस्थानविशेषः—आकारविशेषो यस्येत्यर्थः ॥ कथं तर्हि तथा व्यवहार इत्यत आह—निर्ज्ञातमिति । एवं च तस्माज्जातत्वेनावगते तच्छब्दप्रयोग उभयत्रापीति दृष्टान्तत्वोपपत्तिः ॥ अन्ये तु काकाज्जातो यथा काकत्वाभिसंबन्धात्काकः । एवं संप्रसारणाज्जातोऽपि संप्रसारणत्वारोपात् संप्रसारणमिति भाष्यार्थमाहुः ॥

(समाधानान्तरभाष्यम्)

अथवा—दृश्यन्ते हि वाक्येषु वाक्यैकदेशान् प्रयुञ्जानाः, पदेषु पदैकदेशान् । वाक्येषु तावद्वाक्यैकदेशान्-प्रविश पिण्डीम्, प्रविश तर्पणमिति । पदेषु पदैकदेशान्—देवदत्तः - दत्तः, सत्यभामा - भामेति । एवमिहापि—'संप्रसारणनिर्वृत्तात् संप्रसारणनिर्वृत्तस्य' इत्येतस्य वाक्यस्यार्थे 'संप्रसारणात् संप्रसारणस्य' इत्येष वाक्यैकदेशः प्रयुज्यते । तेन निर्वृत्तस्य विधिं विज्ञास्यामः—संप्रसारणनिर्वृत्तात् संप्रसारणनिर्वृत्तस्येति ॥

(प्रदीपः) प्रविशेति । प्रवेशनक्रिया कर्म योग्यमाक्षिपति, तत्र पिण्ड्यां प्रवेशासंभवाद्गृहप्रतिपत्तिः । एवं पिण्डीमितिकर्म योग्यां क्रियामाक्षिपत् भक्षणक्रियां प्रकरणवशात्प्रत्याययति । एवं संप्रसारणादित्येतन्निर्वृत्तार्थमाक्षेप्स्यतीत्यर्थः । यथा च पदैकदेशप्रयोगः, तथा सिद्धे शब्दार्थसम्बन्धे इत्यत्र प्रतिपादितम् ॥

(उद्योतः) वाक्येष्विति । स्वार्थबोधनाय वाक्येषु प्रयोक्तव्येष्वित्यर्थः ॥ योग्या क्रिया दर्शनादिरपीत्यत आह—प्रकरणेति । तत्तद्वाक्यस्य वाक्यार्थे शक्तिग्रहकाले तत्तदेकदेशस्यापि तत्तद्वाक्यार्थे शक्तिग्रहः, पदैकदेशस्य पदार्थ इव - इति शक्त्यैव बोधः ॥ पूर्वपरिहारे संप्रसारणपदस्य तज्जन्यवर्णे उपचारात्प्रयोगः, अत्र त्वेकदेशेनैव शक्त्या तदर्थप्रतिपत्तिरिति भेदः । तदाह—आक्षेप्स्यतीति । आक्षेपोऽत्र बोधनमेव ॥ भाष्ये—इत्येतस्य वाक्यस्यार्थे इति । अत्र वाक्यपदं पदसमुदायपरम् । इत्येतस्य—इत्येतदर्थकस्य । संप्रसारणादुत्पन्नो यस्तस्मादित्यस्येति संप्रसारणस्य यत्कार्यं तस्येति च वाक्यस्यार्थे - इत्यर्थः ॥

(समाधानान्तरभाष्यम्)

अथवा—आहायं संप्रसारणात्परः पूर्वो भवति, संप्रसारणस्य दीर्घो भवतीति । न च वाक्यस्य संप्रसारणसंज्ञायां सत्यामेष निर्देश उपपन्नः, नाप्येतयोः कार्ययोः संभवोऽस्ति । तत्र वचनाद्भविष्यति ॥

(प्रदीपः) अथवेति । यथा ब्राह्मणशतं भोज्यतामित्युक्ते सामर्थ्यात्संख्येया ब्राह्मणा भोज्यन्ते, तथेहापि 'संप्रसारणात्' इत्युक्ते वाक्यार्थेन पौर्वापर्याभावात्तत्फलस्य वर्णस्य प्रतीतिः ॥

(उद्योतः) पूर्वेभ्यः पक्षेभ्योऽस्य भेदमाह—यथा ब्राह्मणेति । एवं च यथा तत्र संख्याऽन्वयः संख्येयद्वारा, तथा प्रकृते स्वनिर्वृत्तद्वारेति भावः । तदेवाह—तत्फलस्येति । यथा पितृनाम्ना सङ्कल्पितं द्रव्यं तस्यायोग्यत्वे तत्पुत्राय समर्प्यते तद्वदिति भावः ॥

(द्वितीयपक्षाभ्युपगमभाष्यम्)

अथवा पुनरस्तु वर्णस्य ॥

(उक्ताक्षेपस्मारणभाष्यम्)

ननु चोक्तम्—*वर्णसंज्ञा चेन्निर्वृत्तिः* इति ॥

(समाधानभाष्यम्)

नैष दोषः । इतरेतराश्रयमात्रमेतच्चोदितम् । सर्वाणि चेतरेतराश्रयाण्येकत्वेन परिहृतानि—*सिद्धं तु नित्यशब्दत्वात्* इति ॥

(उद्योतः) भाष्ये—एकत्वेनेति । साजात्यादेकत्वेन विशिष्टानि बुद्ध्या कृत्वेत्यर्थः । सर्वेषामेकत्वेनैकजातीयत्वेनैकपरिहारेण सर्वाणि परिहृतानीति भावः ॥

(समाधानबाधकभाष्यम्)

नेदं तुल्यमन्यैरितरेतराश्रयैः । न हि तत्र किंचिदुच्यते—अस्य स्थाने ये आकारैकारौकारा भाव्यन्ते ते वृद्धिसंज्ञा भवन्तीति । इह हि पुनरुच्यते—इग्यणः स्थाने वर्णः स संप्रसारणसंज्ञो भवतीति ॥

(उद्द्योतः) नेदं तुल्यमिति । नित्यशब्दवादेऽपि यण्स्थानिकत्वस्य शास्त्रैकसमधिगम्यत्वादिति भावः ॥

(समाधानसाधकभाष्यम्)

एवं तर्हि भाविनीयं संज्ञा विज्ञास्यते । तद्यथा— कश्चित्कञ्चित् तन्तुवायमाह—'अस्य सूत्रस्य शाटकं वय' इति । स पश्यति—यदि शाटकः, न वातव्यः । अथ वातव्यः, न शाटकः । शाटको वातव्यश्चेति विप्रतिषिद्धम्, भाविनी खल्वस्य संज्ञाऽभिप्रेता । स मन्ये वातव्यः—यस्मिन्नुते शाटक इत्येतद्भवति— इति । एवमिहापि स यणः स्थाने भवति यस्याभिनिर्वृत्तस्य संप्रसारणमित्येषा संज्ञा भविष्यति ॥

(प्रदीपः) भाविनीति । इग्यणः संप्रसारणमिति विधिप्रदेशेषु भाविसंज्ञाविज्ञानमित्यर्थः ॥

(उद्द्योतः) भाविसंज्ञेति । संप्रसारणादिपदस्य तत्त्वेन व्यवहरिष्यमाणे लक्षणेति भावः ॥ अयं समानाधिकरण्यादिविषयेऽपि बोध्यः ॥

(समाधानान्तरभाष्यम्)

अथवा—इजादिप्रवृत्तिर्यजादिप्रवृत्तिश्चैव हि लोके लक्ष्यते । यजाद्युपदेशात्तु इजादिनिवृत्तिः प्रसक्ता । प्रयुञ्जते च पुनर्लौकाः—'इष्टम्-उप्तम्' इति । ते मन्यामहे—अस्य यणः स्थाने इममिकं प्रयुञ्जते इति । तत्रासाध्वभिमतस्य शास्त्रेण साधुत्वमन्वाख्यायते—क्ङिति साधुर्भवति, ङिति साधुर्भवतीति ॥ इग्यणः संप्रसारणम् ॥ ४५ ॥

(प्रदीपः) सिद्धं तु नित्यशब्दत्वादित्येतत्समर्थनार्थमाह—अथवेति । बुद्धिविपरिणाममात्रं स्थान्यादेशभाव इत्यर्थः ॥ असाध्वभिमतस्येति । प्राक् संप्रसारणशास्त्रादिति भावः ॥ यथासंख्यसंबन्धाद्दुहितरामितीकारस्य संप्रसारणसंज्ञा न भवति । दिव उदित्युत्वे यणादेशे कृते हलि इति दीर्घत्वं तपरकरणान्न भवति-द्युभ्यामिति । अक्षद्युवावित्यत्र संप्रसारणाच्चेति पूर्वैकादेशो न भवति, अचः पश्चात्सन्निधानात् । अथवा वार्णादाङ्गस्य बलीयस्त्वात् ॥ ४५ ॥

(उद्द्योतः) बुद्धीति । तदयं सूत्रार्थः—यण्प्रयोगे प्राप्ते इक् प्रयुज्यमानः संप्रसारणसंज्ञ इति ॥ तज्ज्ञानं च यण्स्थानेज्ज्ञानमात्रेण यश्चिस्वपीत्येतज्ज्ञानं विनाऽपि जातमिति नान्योन्याश्रय इत्यर्थः ॥ यश्चिस्वपीत्यादेश्चायमर्थः—एतत्संबन्धियण्प्रयोगे प्राप्ते इक् प्रयुज्यमानः साधुरस्तीति भावः ॥ असाधौ साधुत्वं प्रमाणाऽभ्युपपादयितुमशक्यमत आह—प्रागिति । एतदेव च अनभिमतमभिमतत्वेऽप्युक्तम् ॥ ननु दुहेर्लुङि उत्तमपुरुषे लसेटि तस्य संप्रसारणत्वे 'अदुहितराम्' इत्यादौ 'हलः' इति दीर्घः स्यादत आह—यथासंख्येति ॥ एवं हि यथासङ्ख्यार्थं लकारोपदेशस्यावश्यकत्वे लृकारोपदेशः किमर्थं इति भाष्यस्वरसभाष्यासङ्गतिरिति चिन्त्यमिदम् । तस्मात् 'संप्रसारणस्य' इत्यादौ तन्त्रावितपरत्वाश्रयणान्न दोषः । अनित्यं चेदं वाक्यसंज्ञापक्षस्थापने वाक्यैकदेशन्यायं वदता भगवता ॥ एतेन 'द्युभ्यां' 'अक्षद्युवौ' इत्यपि सिद्धम् ॥ अचः पश्चादिति । समानाङ्गग्रहणस्य करिष्यमाणत्वादौकारस्य चानङ्गत्वादित्यर्थः । तत्प्रत्याख्यानेऽप्याह—वार्णेति । आङ्ग-उवङ् ॥ ४५ ॥

———

(अथ परिभाषाप्रकरणम्)

(४१ परिभाषासूत्रम् ॥ १ । १ । ७ आ. २)

आद्यन्तौ टकितौ ॥ १ । १ । ४६ ॥

(अन्यथानुपपत्तिनिराकरणाधिकरणम्)

(आक्षेपभाष्यम्)

समासनिर्देशोऽयम् । तत्र न ज्ञायते—क आदिः कोऽन्त इति । तद्यथा—अजाविधनौ देवदत्तयज्ञदत्तौ-इत्युक्ते तत्र न ज्ञायते—कस्याजा धनम्, कस्यावयः—इति ॥

(प्रदीपः) आद्यन्तौ० ॥ ४६ ॥ लोकव्यवहारादत्र क्रमव्यवस्था न सिध्यति, अपि तु शास्त्रेणैवेति प्रदर्शनाय पूर्वः पक्षः—समासनिर्देशोऽयमिति । अभिन्नस्यार्थस्य समासेन प्रतिपादनादित्यर्थः ॥ यद्यपि 'देवदत्तस्य यज्ञदत्तस्य चाजा अवयश्च धनं' इति वाक्येऽपि क्रमव्यवस्था नास्ति, तथापि समासे सुतरां नास्तीति प्रतिपादयितुं समासनिर्देश इत्युक्तम् ॥

(उद्द्योतः) आद्यन्तौ० ॥ ४६ ॥ अपि त्विति । एतदर्थमेव स्थानाख्यप्रमाणेन सिद्धेऽपि यथासङ्ख्यसूत्रमावश्यकमिति भावः ॥ अभिन्नस्य—अपृथग्भूतस्य ॥ सुतरामिति । यत्र न साहित्यस्य नियमेन प्रतीतिः पृथगुपस्थितिश्च, तत्रापि चेन्न क्रमव्यवस्था, किमु वक्तव्यं साहित्यप्रतीतावपृथगुपस्थितौ चेत्यर्थः ॥ तथाऽन्वयबोधे तत्तत्पदार्थानां सर्वसाधारणव्यासज्यवृत्तिधर्मानवच्छिन्नत्वेनोपस्थितिस्तत्रमिति तात्पर्यम् ॥

(समाधानभाष्यम्)

यद्यपि तावल्लोक एष दृष्टान्तः । दृष्टान्तस्यापि तु पुरुषारम्भो निवर्तको भवति ॥

(प्रदीपः) यद्यपीति । दर्शनं-दृष्टं, तस्यान्तः-निश्चयः । यद्यपि लोके एतद्दर्शनमित्यर्थः ॥

(उद्द्योतः) अन्तो निश्चय इति । दर्शनस्यावसानं निश्चये सत्याकाङ्क्षाऽभावाद्भवतीति दृष्टान्तशब्देन निश्चय उच्यते—इत्यर्थः ॥ एतद्दर्शनमिति । निश्चय इत्यर्थः । एवं च यथासंख्यान्वयाभिप्रायेणेदृक्प्रयोगो लोकेऽसाधुरिति भावः ॥

(आक्षेपभाष्यम्)

अस्ति चेह कश्चित्पुरुषारम्भः ?

(उद्द्योतः) भाष्ये—अस्ति चेति । प्रश्नः । चपाठस्त्वयुक्तः, तस्य प्रश्नेऽयुक्तत्वात् ॥

(समाधानभाष्यम्)

अस्तीत्याह ॥

कः ?

संख्यातानुदेशो नाम ॥

(टकितोरागमविषयत्वनिर्णयाधिकरणम्)

(आक्षेपभाष्यम्)

कौ पुनष्टकितावाद्यन्तौ भवतः ?

(उद्द्योतः) भाष्ये-कौ पुनरिति । यौ टकितावाद्यन्तौ तौ किमागमौ, उतादेशौ—इति प्रश्नः ॥

(समाधानभाष्यम्)

आगमावित्याह ॥

(उद्द्योतः) आगमावित्याहेति । आर्थन्तपदसत्त्वादिति भावः ॥

(आदेशवादिन आगमवादिनं प्रति आक्षेपभाष्यम्)

युक्तं पुनर्यन्नित्येषु आगमशासनं स्यात् । नं । नित्येषु नाम शब्देषु कूटस्थैरविचालिभिर्वर्णैर्भवितव्यमनपायोपजनविकारिभिः । आगमश्च नामापूर्वः शब्दोपजनः ॥

(उद्द्योतः) नित्येष्विति । वर्णाः-तद्घटिताः, प्रयोगेषु श्रूयमाणाः शब्दाश्च व्याकरणाकार्या आकाशवन्नित्या इति मते-इदम् ॥

(आगमवादिन आदेशवादिनं प्रति आक्षेपभाष्यम्)

अथ युक्तं यन्नित्येषु शब्देष्वादेशाः स्युः ॥

(आदेशवादिनः समाधानभाष्यम्)

बाढं युक्तम् । शब्दान्तरैरिह भवितव्यम् । तत्र शब्दान्तराच्छब्दान्तरस्य प्रतिपत्तिर्युक्ता ॥

(उद्द्योतः) तत्र शब्दान्तरादिति । प्रसंक्तां शब्दान्तरबुद्धिं विहायेत्यर्थः ॥

(इष्टापत्तिभाष्यम्)

आदेशास्तर्हीमे भविष्यन्ति । अनागमकानां सागमकाः ॥

(आक्षेपभाष्यम्)

तत्कथम् ?

(एकदेशिसमाधानभाष्यम्)

संज्ञाधिकारोऽयम् । आद्यन्तौ चेह संकीर्त्येते । टकारककारावितावुदाह्रियेते । तत्राद्यन्तयोष्टकारककारावितौ संज्ञे भविष्यतः । तत्र "आर्धधातुकस्येड्वलादेः" इत्युपस्थितमिदं भवति—आदिरिति । तेनेकारादिरादेशो भविष्यति ॥

(प्रदीपः) संज्ञाधिकारोऽयमिति । यद्येवं संज्ञा संज्ञिप्रत्यायनार्था संज्ञिनं प्रत्याय्य स्वयमेव निवर्तत इति किमिड्ग्रहणेन, टकावित्येवास्तु ॥ नैष दोषः । इत्संज्ञत्वेन देशविशेष उपलक्ष्यते । तेनेत्संज्ञकस्य यो देशस्तद्देशावस्थितौ टकौ संज्ञे भवत इति आलजाटचावित्याटच्प्रत्यये टकारः संज्ञा न भवति । तत्रेड्ग्रहणेनेकारादिशब्दो गृह्यते । स्थानेऽन्तरतमश्चादेशो भवति । तव्यस्य इतव्यो भवतीति सिद्धमिष्टम् ॥

(उद्द्योतः) अनागमकानामित्यादेर्यद्यपि घुसंज्ञासूत्रे आशय उक्त एव, तथापि तं विस्मृत्य तत्कथमिति प्रश्ने एकदेशी साहचर्यादस्य संज्ञासूत्रत्वेन तदुपपत्तिमाह—संज्ञाधिकारोऽयमिति ॥ तत्र शङ्कते—यद्येवमिति ॥ उपलक्ष्यत इति । एवंचानयोरित्त्वमेव नेति भावः ॥ आटजिति । यद्यपि प्रत्ययविधौ नास्य प्रवृत्तिः, षष्ठीत्यपकर्षणात् । अत एव टा-टिठन्-ऐकागरिकडित्यादौ नास्य प्रवृत्तिः, तथापि डुकः पर्यायेणाद्यन्तता स्यादिति दोष इति बोध्यम् ॥ आटश्चेत्यादिभिस्तु टकारार्थादित्त्वोपलक्षिताकाराद्यनुवादेन वृद्ध्यादिविधानम् ॥ भाष्ये—सङ्कीर्त्येते—प्रथमत उच्चार्येते, उदाह्रियेते—पश्चादुच्चार्येते इत्यर्थः ॥ अन्तरतम इति । अर्थतः श्रुतितश्चेति भावः ॥

(आक्षेपभाष्यम्)

एतावदिह सूत्रम् 'इट्' इति । कथं पुनरियता सूत्रेण इकारादिरादेशो लभ्यः ?

(समाधानभाष्यम्)

लभ्य इत्याह ॥

कथम् ?

बहुव्रीहिनिर्देशात् । बहुव्रीहिनिर्देशोऽयम्—इकारः ट्-आदिरस्येति ॥

(आक्षेपभाष्यम्)

यद्यपि तावदत्रैतच्छक्यते वक्तुम् । इह तु कथम्—"लुङ्लङ्लृङ्क्ष्वडुदात्तः" इति, यत्राशक्यमुदात्तग्रहणेनाकारो विशेषयितुम् ॥

(प्रत्याक्षेपभाष्यम्)

तत्र को दोषः ?

(प्रत्याक्षेपसमाधानभाष्यम्)

अङ्गस्योदात्तत्वं प्रसज्येत ॥

(प्रदीपः) अङ्गस्योदात्तत्वमिति । तच्चालोऽन्त्यस्येत्यन्त्यस्य स्यात् ॥

(उद्द्योतः) ननु प्रथमातिक्रमे कारणाभावादाद्युदात्तत्वेनेष्टसिद्धिरत आह—तत्रेति ॥

(समाधानभाष्यम्)

नैष दोषः । त्रिपदोऽयं बहुव्रीहिः । तत्र वाक्य एवोदात्तग्रहणेनाकारो विशेष्यते—अकार उदात्त आदिर्यस्येति ॥

(प्रदीपः) त्रिपदोऽयमिति । विशेषणस्याप्युदात्तस्य सौत्रत्वान्निर्देशस्य परनिपातः ॥

(उद्द्योतः) भाष्ये—तत्र वाक्य एवेति । त्रिपदे वाक्ये एवेत्यर्थः ॥ एवः प्रसिद्धौ । एवं च तत्समानार्थकवृत्तावप्यकारविशेषणत्वं सुलभमिति भावः ॥

(आक्षेपभाष्यम्)

यत्र तर्ह्यनुवृत्त्यैतद्भवति—"आडजादीनाम्" इति ॥

(प्रदीपः) **यत्र तर्हीति** । तत्र ध्रुदात्तग्रहणमेवानुवर्तेत इत्यशक्यो बहुव्रीहिराश्रयितुमिति भावः ॥

(समाधानभाष्यम्)

वक्ष्यत्येतत्—*अजादीनामटा सिद्धम्* इति ॥

(प्रदीपः) **वक्ष्यत्येतदिति** । सूत्रस्यैव प्रत्याख्यानाददोष इत्यर्थः ॥

(उद्द्योतः) प्रत्याख्यानादिति । याड्विधायकं च याडुदात्तः परस्मैपदेष्विति पाठ्यमिति न दोषः ॥

(सिद्धान्तिभाष्यम्)

अथवा—यत्तावदयं सामान्येनोपदेष्टुं शक्नोति, तत्तावदुपदिशति—प्रकृतिम्, ततो वलाद्यार्धधातुकम्, ततः पश्चादिकारम् । तेनायं विशेषेण शब्दान्तरं समुदायं प्रतिपद्यते ॥ तद्यथा—खदिरबुर्बुरयोः—खदिरबुर्बुरौ गौरकाण्डौ सूक्ष्मपर्णौ । ततः पश्चादाह—कण्टकवान् खदिर—इति । तेनाऽसौ विशेषेण द्रव्यान्तरं समुदायं प्रतिपद्यते ॥

(प्रदीपः) **अथवेति** । परिभाषापक्षेऽपि न दोष इत्यर्थः न हि व्यवस्थितस्य तव्यस्य पश्चादिकारोऽवयव आगच्छति, येनानित्यत्वं स्यात् । किं तर्हि, नित्यं पदमनेनोपायेनान्वाख्यायते ॥ **खदिरबुर्बुरयोरिति** । निर्धारणे षष्ठी । तयोः कण्टकवान् खदिर इत्युक्ते द्रव्यान्तरं खदिरं प्रतिपद्यते । न तत्र कण्टकास्तदानीमारोप्यन्ते । प्रतिपादनोपाय एवायमित्यर्थः ॥

(उद्द्योतः) आडजादीनामिति कुर्वतः सूत्रकृतो नायं पक्षस्तात्पर्यविषयीभूत इति, अतो घुसंज्ञासूत्रोपपादितमेव पक्षं सिद्धान्त्याह—भाष्ये—अथवेति ॥ परिभाषापक्षेऽपीति । परिभाषात्वेनागमत्वपक्षेऽपीत्यर्थः ॥ भाष्ये—तेनायं विशेषेणेति । ततः पश्चादिकारमित्यन्तेनेत्यर्थः ॥ शब्दान्तरं—तव्याद्यपेक्षया भिन्नं समुदायं—इतव्यादिरूपमित्यर्थः । प्रतिपद्यते—तव्यबुद्धिनिवर्तनेनेत्यर्थः ॥ नित्यं पदमिति । व्याकरणानिष्पाद्यमित्यर्थः ॥ अन्वाख्यायत इति । क्रमेण सिद्धतत्तदवयवप्रतिपादनेन पूर्वपूर्वनिरवयवकबुद्धिविपरिणामद्वारा प्रत्याय्यत इति आदेशस्थल इवात्रापि बुद्धिविपरिणामान्न नित्यत्वहानिः ॥ तदेव दर्शयति—न तत्र कण्टका इति । कण्टकः—सन्नाह उपरितनशुष्कत्वचः ॥ भाष्ये—खदिरबुर्बुरयोरिति । 'सामान्यमुपदिशति' इत्यध्याहृतसामान्यापेक्षया षष्ठी ॥ सामान्यमेव दर्शयति—खदिरबुर्बुरौ गौरकाण्डाविति ॥ द्रव्यान्तरं—कण्टकाद्विशिष्टं तदवयवकम् ॥ समुदायमिति । पतञ्जलिमते गुणसमुदायस्यैव द्रव्यत्वादिति भावः ॥ तत्र यथा गौरकाण्डत्वादिना खदिरेऽपि प्रसक्तां बुर्बुरबुद्धिं कण्टकवानित्यनेन निवर्त्य खदिरबुद्धिः साध्यते तथेहापि सामान्योपदेशात्सर्वत्र तव्यबुद्धौ प्रसक्तायां इड्बोधकविशेषेणागमत्वबोधनद्वारैव इतव्यबुद्धिः साध्यते इत्यर्थः ॥ निरूपितं चैतद् घुसंज्ञापक्षे । अत्र पक्षे वाचकस्यैवानया प्रक्रियया व्युत्पादनम् । उत्तरपक्षे तु कल्पितस्यानेन साक्षाद्बोधनम्, तेन च बोधकस्याखण्डस्य बोधनमिति भेदः ॥

(समाधानान्तरभाष्यम्)

अथवा—एतयाऽऽनुपूर्व्याऽयं शब्दान्तरमुपदिशति प्रकृतिम्, ततो वलाद्यार्धधातुकम्, ततः पश्चादिकारं, यस्मिंस्तस्यागमबुद्धिर्भवति ॥

(प्रदीपः) **अथवेति** । एतदाह—अस्ति-स्तः एधि-इति तत्त्वतो रूपार्थान्वयाभावात्कल्पिताभ्यामन्वयव्यतिरेकाभ्यामिवार्थवत्तामभिलाप्यासत्यप्रकृतिप्रत्ययोपदेशेन सत्यस्य पदस्य व्युत्पादनं क्रियते, रेखागवयेनेव सत्यगवयस्य ॥

(उद्द्योतः) **रूपार्थान्वयाभावादिति** । व्याकरणेन यस्य 'अस्' इति रूपस्यार्थो दर्शितस्तेन रूपेण तस्यार्थस्य प्रयोगेष्वन्वयाभावः, स्तः-एधीत्यादौ व्यभिचारादित्यर्थः ॥ असत्येति । शास्त्रप्रक्रिया कल्पिता, असत्या इत्यर्थः ॥ यद्यपि सत्यगवयो रेखागवयवत्सावयव एव, अत्र कल्पितावयवसदृशावयवानां तत्रान्वयात् । तथापि सत्यं पदमखण्डमेव, एधीत्यादौ शास्त्रकृत्कल्पितावयवसदृशानामनुपलम्भादित्येतत्पक्षनिष्कर्षः ॥ **सत्यस्य पदस्येति** । एवं च रेखागवयवत्कल्पितानित्यपदविषयकं शास्त्रम् । तत्रागमेष्वपि न क्षतिर्न च तल्लोके प्रयुज्यमानम्, किं तु तत्प्रत्याय्यमेव पदं तथेति भावः ॥ **एतये**त्यादिभाष्यस्यायमर्थः—एतया—वक्ष्यमाणयाऽऽनुपूर्व्याऽयं—पाणिनिः शब्दान्तरं—बोधकशब्दापेक्षया भिन्नं रेखागवयस्थानीयं उपदिशति—प्रतिपादयति । तत्रागमबुद्धावपि न शब्दनित्यताहानिरिति ॥

(२५६ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ टकितोराद्यन्तविधाने प्रत्ययप्रतिषेधः ॥ * ॥

(भाष्यम्)

टकितोराद्यन्तविधाने प्रत्ययस्य प्रतिषेधो वक्तव्यः । प्रत्यय आदिरन्तो वा मा भूत् । "चरेष्टः" "आतोऽनुपसर्गे कः" इति ॥

(प्रदीपः) **प्रत्ययप्रतिषेध इति** । प्रत्ययपरत्वस्याप्ययमपवादः प्राप्नोतीति भावः ॥

(उद्द्योतः) ननु टकितोराद्यन्तविधाने कस्यापि प्रत्ययस्याप्राप्तेः कस्य प्रतिषेधो वक्तव्य इत्यत आह—**प्रत्ययपरत्वस्यापीति** । अपिना स्थानेयोगत्वस्य ॥

(समाधाने वार्तिकांशानुवादभाष्यम् ॥)

॥ परवचनात्सिद्धम् ॥

(भाष्यम्)

परवचनात्प्रत्यय आदिरन्तो वा न भवति ॥

(प्रदीपः) **परवचनादिति** । पुरस्तादपवादन्यायेन स्थानेयोगत्वमेवानेन बाध्यते, न प्रत्ययपरत्वमिति भावः ॥

(२५७ समाधानबाधकैकदेशिवार्तिकम् ॥ २ ॥)

॥ * ॥ परवचनात्सिद्धमिति चेन्नापवाद-

त्वात् ॥ * ॥

(भाष्यम्)

परवचनात्सिद्धमिति चेत् । तन्न ।

किं कारणम् ?

'अपवादत्वात्' । अपवादोऽयं योगः ॥ तद्यथा— "मिदचोऽन्त्यात्परः" इत्येष योगः स्थानेयोगत्वस्य प्रत्ययपरत्वस्य चापवादः ॥

(प्रदीपः) नापवादत्वादिति । बाध्यमात्रापेक्षायां पुरस्तादपवादन्यायो नास्तीति भावः ॥

(समाधानसाधकदृष्टान्तवैषम्यभाष्यम्)

विषम उपन्यासः । युक्तं तत्र यदनवकाशं मित्करणं स्थानेयोगत्वं प्रत्ययपरत्वं च बाधते । इह तु पुनरुभयं सावकाशम् ॥

कोऽवकाशः ?

टित्करणस्यावकाशः-'टितः' इति ईकारो यथा स्यात् । कित्करणस्यावकाशः-'किति' इत्याकारलोपो यथा स्यात् ॥

(उद्द्योतः) भाष्ये—युक्तं तत्रेति । नुम्श्नमादीनां मित्त्वमनवकाशम् ॥ उभयं—प्रत्ययसंबन्धि टित्त्वं कित्त्वं च । एवं चागमटित्त्वकित्त्वयोरनवकाशत्वात्प्रत्ययसंबन्धिनश्च सावकाशत्वाद्येन नाप्राप्तिन्यायेनेदं स्थानेयोगत्वस्यैवापवाद इति भावः ॥

(समाधानबाधकापवादत्वसाधकभाष्यम्)

प्रयोजनं नाम तद्वक्तव्यम्, यन्नियोगतः स्यात् । यदि चायं नियोगतः परः स्यात्तत एतत्प्रयोजनं स्यात् ॥ कुतो नु खल्वेतत्—टित्करणाच्च परो भविष्यति - इति, न पुनरादिरिति । कित्करणाच्च परो भविष्यति - इति, न पुनरन्त इति ?

(प्रदीपः) सर्वापवादबाधामाह-प्रयोजनमिति । सति परत्वे प्रयोजनमेतत्स्यात्, परत्वमेव त्वलभ्यमित्यर्थः ॥ टित्करणादिति । ङीबर्थादित्यर्थः ॥ कित्करणादिति । आकारलोपार्थात् ॥

(उद्द्योतः) सति परत्वे इति । टिदन्तान्ङीब्विधानात्, किति परे आलोपविधानाच्चेति भावः ॥ 'टित्परो भवति' इति वचनाभावादाह— ङीबर्थादिति । यद्यप्युभयथा टित्त्वस्य सावकाशत्वे परत्वात्परश्चेत्यस्य प्रवृत्त्या पर एव भविष्यति, तथापि मिदचोऽन्त्यादिति साहचर्याद्बाध्यसामान्यचिन्तामेव न्याय्यां मन्यते ॥

(किदंशेऽपवादत्वबाधकभाष्यम्)

टितः खल्वप्येष परिहारः । यत्र नास्ति संभवः-यत्परश्च स्यादादिश्च ॥ कितस्त्वपरिहारः, अस्ति संभवो यत्परश्च स्यादन्तश्च ॥

(प्रदीपः) प्रयोजनमभ्युपगम्याप्याह—टित इति ॥ कितस्त्विति । ननु परत्वावयवत्वयोर्विरोधात्कथमुच्यते—परश्च स्यादन्तश्च-इति ॥ नैष दोषः । परस्य सतोऽन्तवत्कार्यप्राप्त्याऽन्तत्वमुच्यते, यथा समासान्तानाम् ॥

(उद्द्योतः) अभ्युपगम्य परश्चेत्यस्य परत्वात् प्रवृत्तिमाह— टितः खल्वपीति ॥ एष परिहारः-युक्तं तत्रेत्यादिनोक्तः । टितो यथाकथंचिद्भवेदपीत्यर्थः । तत्रासंभवरूपविरोधसद्भावात् । किति तु तदभावात्समावेशः स्यादिति भावः ॥ [अवयवत्वेति । अन्तशब्दोऽवयववाचीति भावः ॥]

(आक्षेपभाष्यम्)

तत्र को दोषः ?

(समाधानभाष्यम्)

"उपसर्गे घोः किः" आध्योः-प्रध्योः । "नोङ्धात्वोः" इति प्रतिषेधः प्रसज्येत ॥

(उद्द्योतः) तत्र दोषमाह—नोङित्यादि ॥

(टिदंशेऽप्यपवादत्वबाधकभाष्यम्)

टितश्चाप्यपरिहारः । स्यादेव ह्ययं टित्करणादादिः, न पुनः परः ॥

(प्रदीपः) टितश्चापीति । पूर्वोक्तमेव समर्थयतेऽधिकं वक्तुम् ॥

(उद्द्योतः) पूर्वोक्तम्-कुतो नु खल्वित्यादिनोक्तम् । अधिकम्-ङीपोऽनवकाशत्वपूर्वपक्षसमाधानम् ॥ भाष्ये—स्यादेव हीति । बाध्यसामान्यचिन्तामेव न्याय्यां मन्यते ॥

(आक्षेपभाष्यम्)

क तर्हि इदानीमिदं स्यात्—टित ईकारो भवतीति ?

(समाधानभाष्यम्)

य उभयवान्—"गापोष्टक्" इति ॥

(प्रदीपः) गापोष्टगित्यत्र कित्त्वात्परत्वादन्तत्वमिति टिदन्तमेतद्भवतीति ङीपोऽयमवकाशः । ततश्च चरेष्ट इत्ययमादिः स्यात् ॥

(उद्द्योतः) परत्वादिति । शब्दपरविप्रतिषेधात् । आद्यन्ताविति सूत्रे च 'किद् अन्तः' इत्यस्य परत्वादित्यर्थः ॥ भाष्ये—गापोष्टगित्युपलक्षणं नदट्चोरडादीनाम् ॥

(२५८ सिद्धान्त्येकदेशिसमाधानवार्त्तिकम् ॥ ३ ॥)

॥ * ॥ सिद्धं तु षष्ठ्यधिकारे वचनात् ॥ * ॥

(भाष्यम्)

सिद्धमेतत् ।

कथम् ?

'षष्ठ्यधिकारे वचनात्' । षष्ठ्यधिकारेऽयं योगः कर्तव्यः—"आद्यन्तौ टकितौ षष्ठीनिर्दिष्टस्य" इति ॥

(प्रदीपः) षष्ठ्यधिकार इति । यत्र स्थानषष्ठी प्राप्ता

तत्रोपस्थानमस्याः, न तु प्रत्ययपरत्वबाधनाय ॥

(उद्द्योतः) वाध्यसामान्यचिन्ताश्रयणेऽपि दोषाभावमाह—सिद्धं त्विति ॥ षष्ठ्यधिकारे इति । तत्रानुवर्तेदं व्याख्येयम्, तत्रत्यषष्ठीपदं वाऽत्रापकृष्टव्यमिति भावः ॥ प्राप्नोति । एतदुपस्थितेः प्रागिति शेषः ॥ न त्विति । प्रत्ययविधौ प्रसक्तस्थानषष्ठ्यभावादित्यर्थः ॥

(२५९ सिद्धान्त्येकदेशिसमाधानान्तरवार्तिकम् ॥ ४ ॥)

॥ * ॥ आद्यन्तयोर्वा षष्ठ्यर्थत्वात्तद्भावेऽसंप्रत्ययः ॥ * ॥

(भाष्यम्)

आद्यन्तयोर्वा षष्ठ्यर्थत्वात्तदभावे – षष्ठ्यभावे असंप्रत्ययः–आदिरन्तो वा न भविष्यति ॥

(प्रदीपः) आद्यन्तयोर्वेति । षष्ठ्याः प्रयोजकावाद्यन्तौ । षष्ठ्यभावाचाद्यन्ताभावावगतिरित्यर्थः ॥

(उद्द्योतः) भाष्ये-षष्ठीपदासंबन्धेऽपि समाधानमाह—आद्यन्तयोर्वेति । अर्थशब्दः प्रयोजनवाची ॥ षष्ठ्यर्थत्वादिति बहुव्रीहिरित्याह—षष्ठ्याः प्रयोजकाविति । षष्ठ्यर्थस्य प्रयोजकावित्यर्थः ॥ षष्ठ्यन्तार्थस्यावयवभूताद्यन्तनिरूपकत्वेन तत्प्रयोजकत्वमेतयोर्बोध्यम् ॥ यद्यत्रावयवभूताद्यन्तरूपोऽर्थः स्यात्तदा तस्य निरूपकाकाङ्क्षत्वात् स्यादेव षष्ठ्यर्थः, तद्बोधनाय च षष्ठीप्रयोगः । न च सोऽस्ति । तस्मादाद्यन्ताभावावगतिरिति भावः । भाष्ये-षष्ठ्यभावे इत्यस्य तदर्थाभावे इत्यर्थः ॥

(आक्षेपभाष्यम्)

युक्तं पुनर्यच्छब्दनिमित्तको नामार्थः स्यात् । नार्थनिमित्तकेन नाम शब्देन भवितव्यम् ॥

(प्रदीपः) युक्तं पुनरिति । शब्दभावाभावाभ्यामर्थभावाभावयोः शब्दनिमित्तकत्वमर्थस्य प्राप्तम्, तच्च पुनर्न युक्तम् । ज्ञापको हि शब्दोऽर्थस्य न तु कारकः, सर्वेण सर्वस्यार्थस्य क्रियाप्रसङ्गादिति भावः ॥

(उद्द्योतः) षष्ठीरूपशब्दाभावात्तदर्थाभावस्तदभावाद्याद्यन्ताभाव इत्यर्थं मन्वानस्य शङ्का-भाष्ये—युक्तं पुनरिति ॥ नार्थेत्यत्र काकुः ॥ शब्दभावेति । षष्ठीसत्त्वे तदर्थसत्त्वादाद्यन्तस्थितिः, षष्ठ्यभावे तदर्थाभावादाद्यन्ताभाव इत्युक्तेरिति भावः ॥ कारकत्वे बाधकमाह—सर्वेण–रत्नादिशब्देन । सर्वस्य–रत्नादिरूपस्य ॥

(समाधानभाष्यम्)

अर्थनिमित्तक एव शब्दः ॥

तत्कथम् ?

आद्यन्तौ षष्ठ्यर्थौ । न चात्र षष्ठीं पश्यामः । ते मन्यामहे—आद्यन्तावेवात्र न स्तः । तयोरभावे षष्ठ्यपि न भवतीति ॥ आद्यन्तौ टकितौ ॥ ४६ ॥

(प्रदीपः) अर्थनिमित्तक एवेति । अर्थ एव शब्दस्य प्रयोजकः, तत्प्रतिपादनाय शब्दप्रयोगः । अप्रयोगात्त्वनुमीयते–नूनमर्थ एवात्र प्रयोजको नास्ति, शब्दप्रयोगं यः प्रयुञ्जीतेत्यर्थः ॥ चरेष्ट इत्यत्र परश्चेत्यधिकारात् पञ्चम्येव युक्ता । गापोष्टक्व्रीहिशाल्योर्ढगित्यादावप्यानन्तर्यसंबन्धे षष्ठी, न त्ववयवावयविसंबन्धे । प्रत्ययपरत्वेन प्रतियोगं संनिहितेनाकाङ्क्षाविच्छेदादनर्थित्वादस्यानुपस्थानात् । पुरस्तादपवादन्यायस्तु यथोद्देशपक्षे संभवति, न कार्यकालपक्ष इति नाश्रितः ॥ ४६ ॥

(उद्द्योतः) भाष्ये समाधत्ते—अर्थनिमित्तक एवेति । तद्याचष्टे—अर्थ एवेति ॥ अनुमीयते इति । कार्याभावेन कारणाभावोऽनुमीयते । यथा नदीपूराभावेनोपरिदेशे वृष्ट्यभाव इति भावः ॥ भाष्ये—आद्यन्तौ–तावर्थौ षष्ठ्यर्थद्वारा षष्ठीप्रयोगप्रयोजकौ इत्यर्थः ॥ एवं कार्याभावात्कारणाभावानुमाने कारणाभावात्कार्यमपि नेति निगमयति—भाष्ये—तयोरभाव इति ॥ ननु प्रत्ययविधावपि क्वचित्षष्ठी दृष्टेत्यत आह—चरेष्ट इत्यादि ॥ न त्विति । एतत्सूत्रोपस्थानेनेति भावः ॥ तत्र हेतुमाह–प्रत्ययेति ॥ आकाङ्क्षेति । देशांश इत्यर्थः ॥ अनर्थित्वात्–एतदाकाङ्क्षाभावात् । अत एव धातोः प्रातिपदिकादित्यधिकारानुग्रहो भवति, धात्वादिभ्यः परो गाऽऽदिभ्योऽनन्तर इत्यर्थ ॥ न कार्यकालेति । एतच्च त्वमिको गुणवृद्धी इत्यत्र निरूपितम् । वस्तुतस्त्वाश्रित एव, परवचनात्सिद्धमित्यस्यैव सिद्धान्तयुक्तित्वात् । नापवादत्वादित्यादेः पूर्वपक्ष्येकदेशिसिद्धान्त्येकदेशिनोरुक्तित्वादिति तत्त्वम् ॥ ४६ ॥

(४२ परिभाषासूत्रम् ॥ १ । १ । ७ आ. ३)

मिदचोऽन्त्यात्परः ॥ १ । १ । ४७ ॥

(सूत्रवाक्यनिर्णयः)

(आक्षेपभाष्यम्)

किमर्थमिदमुच्यते ?

(प्रदीपः) मिदचोऽन्त्या० ॥ ४७ ॥ किमर्थमिति । किमनेन व्यावर्त्यत इति प्रश्नः ॥

(उद्द्योतः) मिदचो० ॥ ४७ ॥ प्रयोजनप्रश्नेऽपवादत्वामिधानमसङ्गतमत आह—किमिति । किं व्यावर्त्यत्वेन प्रयोजनमित्यर्थः । किं स्थानेयोगत्वं, उत प्रत्ययपरत्वमपीति प्रश्न इति भावः ॥

(२६० सिद्धान्तवार्तिकम् ॥ १ ॥)

॥ * ॥ मिदचोऽन्त्यात्पर इति स्थानपरप्रत्ययापवादः ॥ * ॥

(भाष्यम्)

मिदचोऽन्त्यात्पर इत्युच्यते स्थानेयोगत्वस्य प्रत्ययपरत्वस्य चापवादः । स्थानेयोगत्वस्य तावत्—कुण्डानि-वनानि-पयांसि-यशांसि । प्रत्ययपरत्वस्य—भिनत्ति-छिनत्ति ॥

(प्रदीपः) स्थानेति । परस्य सतः प्रत्ययस्यापवादः, तेन सामर्थ्यादयमर्थः—प्रत्ययपरत्वस्यापवाद इति ॥ कुण्डानीति । 'नपुंसकस्य झलचः' इत्यत्र झलज्भ्यां नपुंसकस्य तदन्तविधिरित्यस्ति स्थानेयोगत्वप्रसङ्गः । मित्त्वाच्चास्मिन्नुपस्थिते नपुंसकस्याङ्गस्येत्यवयवषष्ठी संपद्यते ॥

(उद्योतः) उभयाप्राप्तत्वे बीजं तु तत्र तत्र मित्त्ववैयर्थ्यरूपं पूर्वस्त्र एवोक्तम् ॥ ननु नपुंसकस्येति सूत्रे झलच इति पञ्चमीति कृत्वा स्थानेयोगत्वप्रसक्तोऽत आह—नपुंसकस्येति । पञ्चम्यां हि तस्मादिति परिभाषोपस्थाने 'पयांसि ज्ञानानि' इत्युभयोरप्यसिद्धिरिति पष्ठ्येवेति भावः ॥

(आक्षेपभाष्यम्)

भवेदिदं युक्तमुदाहरणम्—कुण्डानि, वनानि—इति । यत्र नास्ति संभवो यदयमचोऽन्त्यात्परश्च स्यात् स्थाने चेति ॥

इदं त्वयुक्तम्—पयांसि, यशांसि—इति । अस्ति हि संभवो यदयमचोऽन्त्यात्परश्च स्यात् स्थाने च ॥

(प्रदीपः) स्थाने चेति । ततश्च सकारस्य स्थाने नुम् भवत्वित्यर्थः ॥

(समाधानभाष्यम्)

एतदपि युक्तम् ॥

कथम् ?

नैवेश्वर आज्ञापयति, नापि धर्मसूत्रकाराः पठन्ति—अपवादैरुत्सर्गा बाध्यन्तामिति ॥

किं तर्हि ?

लौकिकोऽयं दृष्टान्तः । लोके हि सत्यपि संभवे बाधनं भवति । तद्यथा—'दधि ब्राह्मणेभ्यो दीयतां तक्रं कौण्डिन्याय' इति, सत्यपि संभवे दधिदानस्य तक्रदानं निवर्तकं भवति । एवमिहापि सत्यपि संभवे अचामन्त्यात्परत्वं षष्ठीस्थानेयोगत्वं बाधिष्यते ॥

(प्रदीपः) दृष्टान्त इति । निश्चय इत्यर्थः । तत्र वृद्धव्यवहारादेव एव वाक्यार्थे व्युत्पत्तिर्यत्सामान्यविहितो विशेषविहितेन बाध्यते, न समुच्चीयते नापि विकल्प्यते ॥

(उद्योतः) भाष्ये—नैवेश्वर इति । ईश्वरः-वेदः ॥ धर्मसूत्रम्-धर्मशास्त्रम् ॥ भाष्ये—अपवादैरित्यस्यासंभवे इत्यादिः ॥ क्वचित्तथैव पाठः ॥ बाध्यन्तामिति । लोट् ॥

(सूत्राप्रवृत्तिनिरूपणम्)

(२६१ सिद्धान्ताक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ अन्त्यात्पूर्वो मस्जेर्मिदनुषङ्गसंयोगादिलोपार्थम् ॥ * ॥

(भाष्यम्)

अन्त्यात्पूर्वो मस्जेर्मिद्वक्तव्यः ॥

किं प्रयोजनम् ?

'अनुषङ्गसंयोगादिलोपार्थम्' । अनुषङ्गलोपार्थं संयोगादिलोपार्थं च । अनुषङ्गलोपार्थं तावत्—मग्नः, मग्नवान् । संयोगादिलोपार्थम्—मङ्क्ता, मङ्क्तुम्, मङ्क्तव्यम् ॥

(उद्योतः) मग्न मस्जेर्जात्पूर्वे नुमि अनिदितामिति लोपे सस्य संयोगादिलोपे कृते निष्ठानत्वे रूपम् । अन्त्याचः परे तु सति अविशेषेण संयोगत्वे संयोगादिलोपसिद्धावपि तस्यासिद्धत्वान्नस्योपधात्वाभावान्नलोपो न स्यादिति भावः ॥ संयोगादिलोपस्तु बहूनां समवधाने बहूनामेव संयोगसंज्ञेति पक्षे फलत्वेन बोध्यः ॥ 'मङ्क्ता' इत्यादि त्वनुषङ्गलोपाभावेऽपि उदाहरणमुक्तं भाष्ये ॥

(२६२ आक्षेपवार्तिकम् ॥ २ ॥)

॥ * ॥ भर्जिमर्च्योश्च ॥ * ॥

(भाष्यम्)

भर्जिमर्च्योश्चान्त्यात्पूर्वो मिद्वक्तव्यः । भरूजा, मरीचय इति ॥

(प्रदीपः) भर्जिमर्च्योश्चेति । 'भ्रूजी भर्जने' इत्यस्यौणादिकेऽचि कृते गुणे रपरत्वे च जकारात्पूर्वं ऊमागमः । 'मर्च शब्दार्थे' इत्यस्य चौरादिकस्य णिच्यच इरिति इप्रत्यये णिलोपे चकारात् पूर्वं ईमागमः ॥

(उद्योतः) ऊमीमावौणादिकौ ॥

(आक्षेपकारणभाष्यम्)

स तर्हि वक्तव्यः ॥

(आक्षेपनिरासभाष्यम्)

न वक्तव्यः, निपातनात् सिद्धम् ॥

किं निपातनम् ?

भरूजाशब्दोऽङ्गुल्यादिषु पठ्यते । मरीचिशब्दो बाह्वादिषु ॥

(पूर्वान्तत्वस्थापनम्)

(आक्षेपभाष्यम्)

किं पुनरयं पूर्वान्तः ? आहोस्वित् परादिः ? आहोस्विदभक्तः ?

(प्रत्याक्षेपभाष्यम्)

कथं वाऽयं पूर्वान्तः स्यात् ? कथं वा परादिः ? कथं वाऽभक्तः ?

(समाधानभाष्यम्)

यद्यन्त इति वर्तते, ततः पूर्वान्तः । अथादिरिति वर्तते, ततः परादिः । अथोभयं निवृत्तं, ततोऽभक्तः ॥

(प्रदीपः) पूर्वान्त इति । संघातस्य पूर्वस्यान्तो न तदेकदेशस्य ॥ अथादिरिति । न हि संभवोऽस्ति यदचोऽन्त्यात्परश्च स्यात्, पूर्वस्य चादिः - इति सामर्थ्यात्परादित्वं विज्ञायते ॥

(उद्योतः) नन्वन्त्यादचः परत्वं तस्य च वर्णान्तरावयवत्वमिति विरुद्धमत आह—सङ्घातेति । 'अन्त्यात्' इत्यनेन समुदायाक्षेपेण समुदायस्योपस्थितत्वात् समुदायावयवसन्निधौ समुदायग्रहस्य न्याय्यत्वाच्च वर्णस्य वर्णावयवत्वासम्भवाच्चेत्याशयः ॥ नन्वादिरित्यनुवृत्तौ पूर्वादित्वं कुतो नेत्यत आह—न हीति ॥ परादित्वमिति । वाचनिकमेव वर्णस्य वर्णावयवत्वं दः सीति धुडादेरिवेति भावः ॥

(भाष्यम्)

कश्चात्र विशेषः ?

(२६३ अभक्तत्वे दूषणवार्तिकम् ॥ १ ॥)

॥ * ॥ अभक्ते दीर्घनलोपस्वरणत्वानुस्वारशीभावाः ॥ * ॥

(दीर्घोदाहरणभाष्यम्)

यद्यभक्तो दीर्घत्वं न प्राप्नोति–कुण्डानि, वनानि । "नोपधायाः, सर्वनामस्थाने चासंबुद्धौ" इति दीर्घत्वं न प्राप्नोति ॥ दीर्घ ॥

(प्रदीपः) कुण्डानीति । नान्तमङ्गं न भवतीति दीर्घत्वाप्राप्तिः ॥ ननु * तदादिवचनं स्यादिनुमर्थमित्युक्तम् । एवं तर्हि तत् स्मर्तव्यं भवतीति गौरवापत्तिः ॥

(उद्द्योतः) अभक्ते इति वार्तिकस्य–एते न सिध्यन्तीति शेषः ॥ नन्वभक्तत्वेऽपि नान्तमस्त्येवेत्यत आह—नान्तमङ्गमिति । दीर्घविधावङ्गाधिकारादिति भावः ॥ गौरवापत्तिरिति । प्रतिपत्तिगौरवापत्तिरित्यर्थः ॥

(नलोपोदाहरणभाष्यम्)

नलोप । नलोपश्च न सिध्यति—'अग्ने त्री ते वाजिना त्री षधस्था, ता ता पिण्डानाम्' । "न लोपः प्रातिपदिकान्तस्य" इति नलोपो न प्राप्नोति ॥ नलोप ॥

(उद्द्योतः) त्री ते इति । शेश्छन्दसि बहुलमिति शेर्लोपः । त्रीणि - वाजिनानि, तानि तानीत्यर्थः ॥

(स्वरोदाहरणभाष्यम्)

स्वर । स्वरश्च न सिध्यति—'सर्वाणि ज्योतींषि' । "सर्वस्य सुपि" इत्याद्युदात्तत्वं न प्राप्नोति । स्वर ॥

(प्रदीपः) सर्वाणीति । नुमा सुपो व्यवधानात् स्वरो न सिध्यति ॥

(उद्द्योतः) नुमेति । व्यञ्जनाविद्यमानवद्भावस्तु हल्स्वरप्राप्तौ, स्वरोद्देश्यकविधिप्राप्तौ वा, नान्यत्रेति भावः । सुपीति न तदन्तसप्तमीत्यभिमानेनेदम् ॥

(णत्वोदाहरणभाष्यम्)

णत्व । णत्वं च न सिध्यति—माषवापाणि, व्रीहिवापाणि । पूर्वान्ते प्रातिपदिकान्तनकारस्येति सिद्धम्, परादौ विभक्तिनकारस्येति । अभक्ते नुमो ग्रहणं कर्तव्यम् ॥

न कर्तव्यम् । क्रियते एतन्न्यास एव—"प्रातिपदिकान्तनुम्विभक्तिषु च" इति । णत्व ॥

(प्रदीपः) क्रियते न्यास एवेति । उत्तरपदस्य प्रातिपदिकस्यान्तस्तत्र नकारो गृह्यते । गर्गाणां भगिनी–गर्गभगिनीत्यत्र णत्वं मा भूदित्यवश्यं कर्तव्यं नुमो ग्रहणम् । स हि समुदायभक्तत्वादुत्तरपदस्यान्तो न भवति ॥

(उद्द्योतः) उत्तरपदस्येति । एवं च सर्वपक्षेष्वपीदमावश्यकमिति भावः ॥ भगशब्दादिनौ तन्नकारः प्रातिपदिकान्तो भवतीति भगिनीत्यत्रानुच्यमाने उत्तरपदस्येत्यस्मिन् णत्वप्रसङ्गः । भगिनीत्यत्र च ङ्यन्तमुत्तरपदं, न नान्तम् । सूत्रं तु 'माषवापिणौ' इत्यादौ चरितार्थमिति भावः ॥ स हीति । नुम्विधायकस्येत्यधिकारादित्यर्थः । एवं च 'माषवापाणि' इत्यादिसिद्ध्यर्थं नुम्ग्रहणमिति भावः ॥ समासरूपप्रातिपदिकान्तस्येत्यर्थेन 'गर्गभगिनी'इत्यस्य व्यावृत्तौ 'माषवापाणि'इत्यस्य सिद्धौ च 'प्रहिण्वन्'इत्याद्यर्थं नुम्ग्रहणमावश्यकमिति तत्त्वम् ॥

(अनुस्वारोदाहरणभाष्यम्)

अनुस्वार । अनुस्वारश्च न सिध्यति—द्विषंतपः, परंतपः । 'मोऽनुस्वारो-हलि' इत्यनुस्वारो न प्राप्नोति ॥

मा भूदेवम् । "नश्चापदान्तस्य झलि" इत्यनुस्वारो भविष्यति ॥

यस्तर्हि न झल्परः—वहंलिहो गौः, अभ्रंलिहो वायुः ॥ अनुस्वार ॥

(प्रदीपः) द्विषंतप इति । प्रसङ्गोच्चारितमेतत् । अत्र हि तन्मध्यपतितस्तद्ग्रहणेन गृह्यत इति नुमो द्विषद्ग्रहणेन ग्रहणमस्ति ॥

(उद्द्योतः) द्विषन्तपादौ द्विषत्परयोस्तापेरिति खच् । खचि ह्रस्वः । अरुर्द्विषदिति मुम् ॥ प्रसङ्गेति । द्विषद्ग्रहणेन मुम्विशिष्टस्य ग्रहणे तस्य पदत्वात्तकारस्य संयोगान्तलोपे एकदेशविकृतन्यायेन 'द्विषम्' इत्यस्य मान्तस्य पदत्वात्सिद्धोऽनुस्वार इत्यर्थः ॥ वस्तुतस्तस्य न्यायस्याप्यज्ञानात्तदनाश्रयेणेदम् । बहिरङ्गासिद्धत्वं त्रिपाद्यां नेति तत्रोक्तम् ॥ वहंलिहे—वहाभ्रे लिह इति खश् ॥

(शीभावोदाहरणभाष्यम्)

शीभाव । शीभावश्च न सिध्यति—त्रपुणी, जतुनी, तुम्बुरुणी । नपुंसकादुत्तरस्यौङः शीभावो भवतीति शीभावो न प्राप्नोति ॥

(प्रदीपः) त्रपुणी इति । नित्यत्वात् परत्वाच्च नुमि कृते व्यवधानमिति भावः ॥

(परादिपक्षाभ्युपगमभाष्यम्)

एवं तर्हि परादिः करिष्यते ॥

(२६४ परादिपक्षे दूषणवार्तिकम् ॥ २ ॥)

॥ * ॥ परादौ गुणवृद्ध्यौत्वदीर्घनलोपानुस्वारशीभावेनकारप्रतिषेधाः ॥ * ॥

(गुणोदाहरणभाष्यम्)

यदि परादिः, गुणः प्रतिषेध्यः—त्रपुणे, जतुने, तुम्बुरुणे । "घेर्ङिति" इति गुणः प्राप्नोति ॥ गुण ॥

(उद्द्योतः) परादाविति वार्तिके शीभावेनकारप्रतिषेधा इति पाठः । शीभावे इत्यलुगार्षः । एते दोषस्थानानीति शेषः ॥

(वृद्ध्युदाहरणभाष्यम्)

वृद्धि । वृद्धिः प्रतिषेध्या—अतिसखीनि ब्राह्मणकुलानि । "सख्युरसम्बुद्धौ" इति णित्त्वे "अचो ञ्णिति" इति वृद्धिः प्राप्नोति–इति ॥ वृद्धि ॥

(प्रदीपः) अतिसखीनीति । बहुव्रीहिः ॥

(उद्योतः) टजभावाय नपुंसकत्वाय चाह—बहुव्रीहिरिति ॥

(औत्त्वोदाहरणभाष्यम्)

औत्त्व । औत्त्वं च प्रतिषेध्यम्—त्रपुणि, जतुनि, तुम्बुरुणि । "इदुद्भ्याम्-औत्-अच्च घेः" इत्यौत्त्वं प्राप्नोति ॥ औत्त्व ॥

(दीर्घोदाहरणभाष्यम्)

दीर्घ । दीर्घत्वं च न सिध्यति—कुण्डानि, वनानि । "नोपधायाः" "सर्वनामस्थाने-" इति दीर्घत्वं न प्राप्नोति ॥

मा भूदेवम् । "अतो दीर्घो यञि-सुपि च" इत्येवं भविष्यति ॥

इह तर्हि—अस्थीनि, दधीनि, प्रियसखीनि ब्राह्मणकुलानि ॥ दीर्घ ॥

(नलोपोदाहरणभाष्यम्)

नलोप । नलोपश्च न सिध्यति—'अग्ने त्री ते वाजिना त्री षधस्था, ता ता पिण्डानाम्' । "नलोपः प्रातिपदिकान्तस्य" इति नलोपो न प्राप्नोति ॥ नलोप ॥

(उद्योतः) भाष्ये—अग्ने त्री ते इति । ननु परादिपक्षे नलोपः प्रातिपदिकान्तस्येत्यस्याप्राप्तावपि शेश्छन्दसि बहुलमित्येन नलोपः सिद्ध इति चेन्न । निर्दिश्यमानपरिभाषयाऽलोऽन्त्यपरिभाषया च इकारस्यैव लोपापत्तेरित्याशयात् ॥

(अनुस्वारोदाहरणभाष्यम्)

अनुस्वार । अनुस्वारश्च न सिध्यति—द्विषन्तपः, परन्तपः । "मोऽनुस्वारो-हलि" इत्यनुस्वारो न प्राप्नोति ॥

(प्रदीपः) द्विषन्तप इति । परादिपक्षे तकारस्य मकारो भक्तस्तकारश्च पदान्त इति मकारोऽपि तद्भक्तत्वात् पदान्त इति सिद्धोऽनुस्वार इत्याहुः ॥ अन्ये तु तद्भक्तत्वात्तकारग्रहणेनास्य ग्रहणं भवतु न तु पदान्तत्वम् । न हि द्वयोर्मकारतकारयोः पदान्तत्वमुपपद्यत इत्याहुः ॥

(उद्योतः) तद्भक्तत्वात्पदान्त इति । यदागमा इत्यस्य तद्ग्राहकेण शब्देनागमस्य ग्रहणमित्यर्थ इति भावः ॥ न हि द्वयोरिति । ननु संयोगान्तलोपे उक्तरीत्याऽस्यैव मस्य पदान्तत्वमिति चेत्, उक्तमेवैतत् ॥

(उदाहरणनिरासभाष्यम्)

मा भूदेवम् । "नश्चापदान्तस्य झलि" इत्यनुस्वारो भविष्यति ॥

(उदाहरणान्तरभाष्यम्)

यस्तर्हि न झल्परः—वहंलिहो गौः, अभ्रंलिहो वायुः ॥ अनुस्वार ॥

(उदाहरणभाष्यम्)

शीभावे नकारप्रतिषेधः । शीभावे नकारप्रतिषेधो वक्तव्यः—त्रपुणी, जतुनी, तुम्बुरुणी । नुमकस्य शीभावः प्राप्नोति ॥

(प्रदीपः) शीभावे नकारप्रतिषेध इति । शीभावे विधीयमाने नकारस्य स्थानित्वप्रतिषेधो वक्तव्य इत्यर्थः ॥

(उदाहरणनिरासभाष्यम्)

नैष दोषः । 'निर्दिश्यमानस्यादेशा भवन्ति' इत्येवं न भविष्यति ॥

(प्रदीपः) निर्दिश्यमानस्येति । यथा पादः पदिति पद्भावः पाच्छब्दस्यैव भवति, न तदन्तस्य ॥

(उद्योतः) न तदन्तस्येति । पादन्तस्यानुच्चारणादिति भावः ॥

(उदाहरणसाधकभाष्यम्)

यस्तर्हि निर्दिश्यते तस्य न प्राप्नोति ॥

कस्मात् ?

नुमा व्यवहितत्वात् ॥

(प्रदीपः) यस्तर्हीति । यो निर्दिश्यते तस्य न प्राप्नोति । श्रुतिसन्निपाति यद्रूपं 'औ' इति तन्नकारेण भक्तेनापि तत्त्वतो व्यवहितमित्यर्थः ॥

(उद्योतः) श्रुतिसंनिपातीति । उच्चारितमिति यावत् ॥

(पूर्वान्तपक्षाभ्युपगमभाष्यम्)

एवं तर्हि पूर्वान्तः करिष्यते ॥

(२६५ पूर्वान्तपक्षे दूषणवार्तिकम् ॥ ३ ॥)

॥ * ॥ पूर्वान्ते नपुंसकोपसर्जनह्रस्वत्वं द्विगुस्वरश्च ॥ * ॥

(भाष्यम्)

यदि पूर्वान्तः, नपुंसकोपसर्जनह्रस्वत्वं द्विगुस्वरश्च न सिध्यति ॥

(उदाहरणभाष्यम्)

नपुंसकोपसर्जनह्रस्वत्वम् । आराशस्त्रिणी, धानाशष्कुलिनी, निष्कौशाम्बिनी, निर्वाराणसिनी ॥

द्विगुस्वर । पञ्चारत्निनी, दशारत्निनी ॥

नुमि कृते अनजन्तत्वादेते विधयो न प्राप्नुवन्ति ॥

(प्रदीपः) धानाशष्कुलिनी इति । नित्यत्वान्नुमं पूर्वं मन्यते, तत्र कृतेऽनजन्तत्वाद्ध्रस्वाप्राप्तिः ॥ निष्कौशाम्बिनी इति । नपुंसकह्रस्वत्वमुपसर्जनस्य ह्रस्वत्वेन परत्वाद्बाध्यते, तदपि नुमि कृते तथैव न प्राप्नोति ॥

(उद्योतः) धानाशष्कुलिनी इति । समाहारद्वन्द्वे तद्धित्वविवक्षायां द्विवचनम् ॥ तत्र पूर्वं ह्रस्वः, ततो नुमि नास्ति दोष इत्यत आह—नित्यत्वादिति । इदं च पदस्य विभज्यान्वाख्यान-

पक्षे बोध्यम् ॥ अनजन्तत्वादिति । अच इत्यनेन प्रातिपदिकस्य विशेषणादित्यर्थः ॥ परत्वादिति । यद्यपि कार्यैक्ये यौगपद्यासम्भवेन विरोधाभावेन परत्वादित्यसङ्गतम्, तथापि नुमि कृते उभयोरप्यप्राप्त्योभयोः सम्भवसत्त्वेन च न भाष्ये काचिदनुपपत्तिः । अत एव भाष्ये—नपुंसकोपसर्जनह्रस्वत्वमिति संश्लिष्टमेवोक्तमिति बोध्यम् ॥ तथैवेति । अनजन्तत्वादिति भावः ॥

(२६६ दूषणबाधकवार्तिकम् ॥ ४ ॥)

॥ * ॥ न वा बहिरङ्गलक्षणत्वात् ॥ * ॥

(भाष्यम्)

न वा एष दोषः ॥

किं कारणम् ?

'बहिरङ्गलक्षणत्वात्' । बहिरङ्गो नुम्, अन्तरङ्गा एते विधयः ॥

'असिद्धं बहिरङ्गमन्तरङ्गे' ॥

द्विगुस्वरे भूयान् परिहारः—संघातभक्तोऽसौ नोत्सहतेऽवयवस्येगन्ततां विहन्तुमिति कृत्वा द्विगुस्वरो भविष्यति ॥ मिदचोऽन्त्यात्परः ॥ ४७ ॥

(प्रदीपः) न वेति । नित्यादप्यन्तरङ्गो बलीयानिति । स्वरह्रस्वौ च विभक्तिनिरपेक्षत्वादन्तरङ्गौ । तदत्र निर्दोषत्वात्पूर्वान्तपक्षः स्थितः ॥ ४७ ॥

(उद्योतः) अन्तरङ्गो बलीयानिति । असिद्धं बहिरङ्गमित्येव समानकालप्राप्तिकबहिरङ्गासिद्धत्वबोधकं पूर्वजातबहिरङ्गासिद्धत्वबोधकं चेति भावः ॥ अत एव भाष्येणाविरोधः ॥ अकृतव्यूहपरिभाषा तु नास्त्येवेति भावः । पञ्चारत्निशब्दे समाहारे द्विगुः, प्रमाणे मात्रचो लुग्वा ॥ ४७ ॥

(इत्यागमस्थितिदेशनिर्णयप्रकरणम्)

(अथादेशनियामकप्रकरणम्)

(४३ परिभाषासूत्रम् ॥ १ । १ । ७ आ. ४ ॥)

एच इग्घ्रस्वादेशे ॥ १ । १ । ४८ ॥

(सूत्रारम्भप्रयोजनम्)

(आक्षेपभाष्यम्)

किमर्थमिदमुच्यते ?

(प्रदीपः) एच इक्० ॥४८॥ किमर्थमिति । विनाऽपि सूत्रेणेष्टसिद्धिरिति प्रश्नः ॥

(उद्योतः) एच इक्० ॥ ४८ ॥ विनाऽपीति । वक्ष्यमाणसूत्रप्रत्याख्यानप्रकारेणेति भावः ॥

(२६७ प्रयोजनवार्तिकम् ॥ १ ॥)

॥ * ॥ एच इग्वचनं सवर्णाकारनिवृत्त्यर्थम् ॥ * ॥

(भाष्यम्)

एच इग्भवतीत्युच्यते सवर्णनिवृत्त्यर्थमकारनिवृत्त्यर्थं च ॥ सवर्णनिवृत्त्यर्थं तावत्—एङो ह्रस्वादेशशासनेषु अर्ध एकारोऽर्ध ओकारो वा मा भूदिति ॥ अकारनिवृत्त्यर्थं च—इमावैचौ समाहारवर्णौ, मात्राऽवर्णस्य मात्रेवर्णोवर्णयोः । तयोर्ह्रस्वशासनेषु कदाचिदवर्णः स्यात्, कदाचिदिवर्णोवर्णौ । मा कदाचिदवर्णं भूदित्येवमर्थमिदमुच्यते ॥

(प्रदीपः) एङ इति । एङः प्रश्लिष्टावर्णत्वात्प्रश्लिष्टावर्णावर्द्धैकारार्द्धौकारौ प्राप्नुतः, न तु विश्लिष्टावर्णयोरैचोरिति भावः ॥ समाहारवर्णाविति । समाह्रियमाणावयवत्वात् ॥ मात्राऽवर्णस्येति । अष्टादशभेदभिन्नस्यावर्णस्य मात्रा—अवयव इति भेदसद्भावात् षष्ठ्या निर्देशः ॥

(उद्योतः) एच इति वक्तव्ये एङ इति अनुचितमत आह—एङ इति ॥ प्रश्लिष्टेति । पांसूदकवदित्यर्थः ॥ प्रश्लिष्टवर्णत्वादिनाऽप्यान्तरतम्यं गृह्यत इति भावः ॥ ऐचोस्तदप्राप्तौ हेतुमाह—न त्विति । ऐचौ त्वर्धौ न स्त एवेति भावः ॥ सवर्णाकारनिवृत्त्यर्थमित्येतद्विषयभेदेन योज्यत इति बोध्यम् ॥ कैर्मधन्तसमाहारशब्दस्य वर्णशब्देन न बहुव्रीहिः, वर्णैकदेशस्य वर्णत्वाभावादत आह—समा यमाणाविति । मध्यमपदलोपी समास इति भावः ॥ मात्राऽवर्णस्येति भाष्यस्य मात्राकालावर्णादिसदृशा ऐचोरवयव इति तात्पर्यम् ॥ मात्रा-अवयव इति । तत्सदृशी चैतयोः, अवयव इत्यर्थः ॥

(भाष्यम्)

अस्ति प्रयोजनमेतत् ॥

किं तर्हीति ?

(अनिष्टापत्तिनिराकरणम्)

(२६८ आक्षेपवार्तिकम् ॥ २ ॥)

॥ * ॥ दीर्घप्रसङ्गस्तु ॥ * ॥

(भाष्यम्)

दीर्घास्त्विकः प्राप्नुवन्ति ॥

किं कारणम् ?

स्थानेऽन्तरतमो भवतीति ॥

(प्रदीपः) दीर्घास्त्विति । स्वतन्त्रमिदं 'इको'निर्वर्तकमिति भावः ॥ भाव्यमानस्यापि सवर्णग्रहणं दृश्यते—अमूभ्यामित्यादाविति दोषोपन्यासः ॥

(उद्योतः) नन्वस्य नियमत्वेन ह्रस्वविध्येकवाक्यतया कथं दीर्घप्राप्तिरत आह—स्वतन्त्रमिति । नियमत्वेऽनुवादादिदोषाद्विधित्वमेव न्याय्यमित्यभिमानः ॥ भाव्यमानस्येति । सम्बन्धसामान्ये षष्ठी ॥

(आक्षेपबाधकभाष्यम्)

ननु च 'ह्रस्वादेशे' इत्युच्यते, तेन दीर्घा न भविष्यन्ति ॥

(प्रदीपः) **ननु चेति** । अयं हि वाक्यार्थः—एचो ह्रस्वप्रसङ्गे इगेव ह्रस्व इति ॥

(आक्षेपसाधकभाष्यम्)

विपर्यार्थमेतत् स्यात्—एचों ह्रस्वप्रसङ्गे इग्भवतीति ॥

(प्रदीपः) **विषयार्थमिति** । यत्र ह्रस्वो विधीयते तत्रैवास्योपस्थानं यथा स्यात्, 'दे३वदत्त' इति प्लुतादिविधावुपस्थानं मा भूत् । अस्मिंश्चोपस्थिते वाक्यभेदेनैच इको विधीयमाना अन्तरतमा दीर्घा एव प्राप्नुवन्ति । ह्रस्वस्य बाधितत्वाद्दीर्घेषु कृतेषु पुनर्ह्रस्वाप्रसङ्गः ॥

(उद्योतः) **देवेति** । देवदत्तेत्येतद्विषयकगुरोरनृत इत्येतद् प्लुतविधावित्यर्थः । आदिनोदात्तादिस्वरसंग्रहः ॥ नन्वनेन दीर्घे पुनस्तेन लक्षणेन ह्रस्वः स्यादत आह—**ह्रस्वस्येति** । अपवादस्य प्रवृत्त्या तद्विषये उत्सर्गाप्रवृत्तेरिति भावः ॥

(२६९ समाधानवार्तिकम् ॥ ३ ॥)

॥ * ॥ दीर्घाप्रसङ्गस्तु निवर्तकत्वात् ॥ * ॥

(भाष्यम्)

दीर्घाणां त्विकामप्रसङ्गः ॥

किं कारणम् ?

'निवर्तकत्वात्' । नानेनेको निर्वर्त्यन्ते ।

किं तर्हि ?

अनिको निवर्त्यन्ते ॥ सिद्धा ह्यत्र ह्रस्वा इकश्चानिकश्च । तत्रानेनानिको निवर्त्यन्ते ॥

(प्रदीपः) **निवर्तकत्वादिति** । एकवाक्यभावेनैच इगेव ह्रस्वो भवति नान्य इत्येवमनिको व्यावर्त्यन्ते ॥ यदि तर्ह्येकवाक्यता, एज्व्यतिरेकेणान्यस्य ह्रस्वो न प्राप्नोति ॥ नैष दोषः । पूर्वं ह्रस्वश्रुत्याऽच उपस्थानाद् ह्रस्वत्वं क्रियते । तत्रैचोऽप्यन्तर्भावाद् ह्रस्वे क्रियमाणे 'एच इक्-' इत्यस्योपस्थानम् ॥

(उद्योतः) **एकवाक्यभावेनैच इति** । एकवाक्यभावो नाम 'एच इक्' इत्यस्य ह्रस्वशेषभावः, न तु परस्परनियोगाभावः ॥ अन्वयस्तु वाक्यभेदेनैवेति ॥ एतदजानानो नोदयति—**यदीति** ॥ उक्ताभिप्रायेणैवोत्तरयति—**पूर्वं ह्रस्वेति** । ऐवं हि परिभाषाद्वयस्याप्यनुग्रहो भवतीति भावः ॥

(सूत्रप्रत्याख्यानम्)

(प्रथमप्रयोजनप्रत्याख्यानभाष्यम्)

सवर्णनिवृत्त्यर्थेन तावन्नार्थः ॥

(२७० प्रत्याख्यानसाधकवार्तिकम् ॥ ४ ॥)

॥ * ॥ सिद्धमेङः सस्थानत्वात् ॥ * ॥

(भाष्यम्)

सिद्धमेतत् ॥

कथम् ?

'एङः सस्थानत्वात्' । इकारोकारौ भविष्यतः, अर्ध एकारोऽर्ध ओकारो वा न भविष्यति ॥

(प्रदीपः) **सिद्धमेङ इति** । एकारस्य तालव्यस्य तालव्य इकारः, ओकारस्य चौष्ठ्यस्यौष्ठ्य उकारो भविष्यतीत्यर्थः ॥

(उद्योतः) **एकारस्येति** । यत्तु कण्ठताल्वादिस्थानत्वेऽपि विप्रतिषेधेन पूर्वावयवो न स्वान्तरतमादेशप्रयोजकः, किंतु परावयव एवेति न दोष इति ॥ तन्न । लक्ष्यगतपरत्वमादाय विप्रतिषेधशास्त्राप्रवृत्तेः स्थानिवत्प्रकरणभाष्ये स्पष्टत्वात् । किन्त्वन्तरङ्गत्वेन पूर्वावयव एव तथेति बोध्यम् ॥ भाष्ये—**अर्धं एकार ओकारो वा न भविष्यतीति** । तयोरसत्त्वादिति भावः ॥

(आक्षेपभाष्यम्)

ननु च एङः सस्थानतरावर्धैकारार्धौकारौ ॥

(उद्योतः) इतरस्तु 'सस्थानत्वाभावात्' इति हेतुरनेनोक्त इति मत्वा नोदयति—**ननु चेति** ॥ **सस्थानतराविति** । कण्ठतालुस्थानमिति पक्षेऽपि स्थानसाम्यसत्त्वमिति बोधयितुं तरनिर्देशः ॥

(समाधानभाष्यम्)

न तौ स्तः । यदि हि तौ स्यातां तावेवायमुपदिशेत् ॥

(उद्योतः) स्वाशयं प्रकटयति—**न तौ स्त इति** ॥ **तावेवेति** । प्रत्याहारसूत्रे-इति भावः । एतच्च एओङ्सूत्रे निरूपितम् ॥

(समाधानबाधकभाष्यम्)

ननु च भोश्छन्दोगानां सात्यमुग्रिराणायनीया अर्धमेकारमर्धमोकारं चाधीयते—'सुजाते एश्व सूनृते' 'अध्वर्यो ओद्रिभिः सुतम्' 'शुक्रन्ते एन्यत्' 'यजतं ते एन्यत्' इति ॥

(समाधानसाधकभाष्यम्)

पार्षदकृतिरेषा तत्रभवताम् । नैव लोके नाप्यन्यस्मिन्वेदे— अर्ध एकारः-अर्ध ओकारो वाऽस्ति ॥

(उद्योतः) **पार्षदेति** । तत्रभवतां या पर्षत्-सभा तत्र भवेत्यर्थः । भाष्यप्रयोगादेव गमकत्वात्साधुत्वं बोध्यम् ॥

(द्वितीयप्रयोजनप्रत्याख्यानभाष्यम्)

अकारनिवृत्त्यर्थेनापि नार्थः ॥

(२७१ प्रत्याख्यानसाधकवार्तिकम् ॥ ५ ॥)

॥ * ॥ ऐचोश्चोत्तरभूयस्त्वात् ॥ * ॥

(भाष्यम्)

ऐचोश्चोत्तरभूयस्त्वादवर्णो न भविष्यति । भूयसी मात्रेवर्णावर्णयोः, अल्पीयस्यवर्णस्य । भूयस एव ग्रहणानि भविष्यन्ति । तद्यथा 'ब्राह्मणग्राम आनीयताम्' इत्युच्यते । तत्र चावरतः पञ्चकारुकी भवति ॥ एच इग्घ्रस्वादेशे ॥ ४८ ॥

(प्रदीपः) **ऐचोश्चेति** । ऐकारः कण्ठतालव्यः, औकारः कण्ठौष्ठ्यः । न च तथाविधो ह्रस्वोऽस्तीति अवयवान्तरतमेन भाव्यम् । भूयसा चाऽवयवेन व्यपदेशो भवति । तदात्मक इव

हि समुदायो लक्ष्यत इतीदुतावेव भविष्यतः ॥ **ब्राह्मणग्राम इति** । ब्राह्मणानां वास्तव्यत्वे उदाहरणम् । न तु स्वामित्वे ॥४८॥

(उद्द्योतः) **भूयस एवेति** । भूयोंऽशस्यान्तरतम्यप्रतियोगितया ग्रहणमित्यर्थः ॥ ब्राह्मणस्वामिकग्रामस्य भूयसा व्यपदेशे दृष्टान्तत्वासङ्गतेराह—**वास्तव्यत्वे इति** । वास्तव्यः-कर्तरि तव्यान्तः । कुलालकर्मारवर्धकिनापितरजकाः पञ्चकारुकी ॥ ४८ ॥

(४४ परिभाषासूत्रम् ॥ १ । १ । ७ आ. ५)

षष्ठी स्थानेयोगा ॥ १ । १ । ४९ ॥

(स्थानेयोगशब्दार्थनिरूपणम्)

(आक्षेपभाष्यम्)

किमिदम्—स्थानेयोगेति ?

(प्रदीपः) **षष्ठी०** ॥ ४९ ॥ **किमिदमिति** । समासे विभक्तिश्रवणाप्रसङ्गः । असमासेऽपि 'युक्तिः' इति प्राप्नोति, न तु योगेति **प्रश्नः** ॥

(उद्द्योतः) **षष्ठी स्था०** ॥ ४९ ॥ **युक्तिरिति** । षष्ठीति स्त्रीलिङ्गविशेषणत्वादिति भावः ॥

(समाधानभाष्यम्)

स्थाने योगोऽस्याः सेयं-स्थानेयोगा । सप्तम्यलोपो निपातनात् ॥

तृतीयाया वा एत्वम् । स्थानेन योगोऽस्याः सेयं-स्थानेयोगेति ॥

(प्रदीपः) **स्थाने योगोऽस्या इति** । स्थाननिमित्तसम्बन्धेत्यर्थः ॥ **तृतीयाया वेति** । 'निपातनात्' इति योज्यम् । यथा देवदत्तस्य यज्ञदत्त इति पुत्रत्वादिद्वारकः संबन्धोऽवगम्यते, एवमस्तेर्भूरित्यत्राप्यस्यां परिभाषायां सत्यां स्थाननिमित्तः संबन्धोऽवसीयते ॥ स्थानं-अर्थं इति केचिदाहुः-तिष्ठन्त्यस्मिन् शब्दा इति स्थानम्, अर्थे च शब्दस्तिष्ठति । तेनास्तेरर्थे भूरित्यर्थः ॥ अन्ये त्वाहुः—**भ्रस्जो रोपधयोरमन्यतरस्यामित्यादौ** रोपधादीनामानर्थक्याद्भावसाधनः प्रसङ्गवाची स्थानशब्द आश्रीयते । तेनास्तेः प्रसङ्गे-अस्तेः प्राप्तौ भूः प्रयुज्यते इत्यर्थः संपद्यते ॥ स्वाभाविकोऽस्तेरप्रयोग आर्धधातुके भूशब्दस्य च प्रयोगोऽनेन प्रकारेणान्वाख्यायते ॥

(उद्द्योतः) **निपातनादिति** । तृतीयान्तस्य समासे तृतीयाया लुक्यस्यैत्वमित्यर्थः ॥ तृतीयायाः स्थाने एतद्विधाने तु अन्तरङ्गत्वाधे मानाभावादिनादेशेऽन्त्यस्य स्यात्, लुग्बाधे मानाभावाच्च । वृद्ध्यापत्तेश्च ॥ अत एवेत्वं नोक्तमिति बोध्यम् ॥ अत्र स्थानस्वामीत्यादयः षष्ठ्यर्थसम्बन्धनिरूपकाः, न तु षष्ठ्यर्था इति न मतुप्सूत्रस्थभाष्यविरोधः । अत एवात्र भगवता सप्तम्यन्तेन तृतीयान्तेन वा समासो दर्शितः, न तु समानाधिकरणबहुव्रीहिः । तदभिप्रायतोक्तम्—**स्थाननिमित्तसंबन्धेत्यर्थं इति** ॥ नन्वादेशविधौ स्थानशब्दाभावेन कथं स्थाननिमित्तः संबन्धोऽत आह—**यथेति** । तथा च 'देवदत्तस्य यज्ञदत्तः' इत्युक्ते किमित्याकाङ्क्षावशात्पुत्र इत्यध्याहारो यथा, तथा प्रदेशेषु स्थानपदाध्याहारेण वाक्यैकदेशन्यायेन वा बोध इति भावः ॥ **अर्थे चेति** । वाचकत्वसंबन्धेनेति भावः ॥ अस्तेः प्रसङ्ग इत्यस्य व्याख्या—**अस्तेः प्राप्ताविति** ॥ **प्रयोग इति** । स्वाभाविक इत्यनुषज्यते । शब्दनित्यत्वभङ्गापत्त्या स्थानशब्दो निवृत्तिवाची नोपपद्यत इति भावः । रम्विधौ रोपधघटितस्यार्थे रम्घटित इत्यर्थे न क्षतिरित्यत्रारुचिः ॥

(सूत्रप्रयोजनम्)

(आक्षेपभाष्यम्)

किमर्थं पुनरिदमुच्यते ?

(प्रदीपः) **किमर्थमिति** । विनाऽपि सूत्रेणेष्टं सिध्यति, आरब्धे चातिप्रसङ्ग इति **प्रश्नः** ॥

(उद्द्योतः) **आरब्धे चेति** । तत्रातिप्रसङ्गवारणाय व्याख्यानत इत्येतदाश्रयणे तथैव सिद्धौ परिभाषेयं व्यर्थेति भावः ॥

(२७२ समाधानवार्तिकम् ॥ १ ॥)

॥ * ॥ षष्ठ्याः स्थानेयोगवचनं नियमार्थम् ॥ * ॥

(भाष्यम्)

नियमार्थोऽयमारम्भः । एकशतं षष्ठ्यर्थाः, यावन्तो वा । ते सर्वे षष्ठ्यामुच्चारितायां प्राप्नुवन्ति । इष्यते च—व्याकरणे या षष्ठी सा स्थानेयोगैव स्यादिति । तच्चान्तरेण यत्नं न सिध्यतीति षष्ठ्याः स्थानेयोगवचनं नियमार्थम् । एवमर्थमिदमुच्यते ॥

(प्रदीपः) **एकशतमिति** । षष्ठीदण्डकपाठाश्रयेणैतदुक्तम् ॥ **यावन्तो वेति** । शब्दे यावतां संभव इत्यर्थः ॥

(उद्द्योतः) **षष्ठीदण्डकपाठः**—ग्रन्थविशेषः ॥ भाष्ये—**षष्ठ्यर्था इति** । षष्ठीप्रयोजकास्तदर्थान्वयिनः शब्दाः शतमित्यर्थः ॥ यद्वा षष्ठ्यर्थानां शतत्वे तेषां शतत्वमर्थसिद्धं बोध्यम् ॥ एकशतमिति निर्णयेनाभिधाय पुनः संदिग्धाभिधानमयुक्तमत आह—**शब्द इति** । वाशब्दो वाक्यालङ्कारे ॥ भाष्ये—**प्राप्नुवन्तीति** । तेषां सर्वेषां बोधः प्राप्नोतीत्यर्थः ॥

(भाष्यम्)

अस्ति प्रयोजनमेतत् ॥

किं तर्हीति ?

(अनिष्टापत्तिनिराकरणम्)

(२७३ आक्षेपवार्तिकम् ॥ २ ॥)

॥ * ॥ अवयवषष्ठ्यादिष्वतिप्रसङ्गः शासो गोह इति ॥ * ॥

(भाष्यम्)

अवयवषष्ठ्यादयस्तु न सिध्यन्ति ॥

तत्र को दोषः ?

"शास इदङ्हलोः" इति शासेश्चान्त्यस्य स्यादुपधामात्रस्य च । "ऊदुपधाया गोहः" इति गोहेश्चान्त्यस्य स्यादुपधामात्रस्य च ॥

(प्रदीपः) अवयवेति । नियमेन संबन्धान्तराणां निवर्तनादिति भावः ॥ उपधामात्रस्येति । शासिना संबन्धाभावात् पचादिसंबन्धिनोऽपीत्यर्थः । तत्र श्नानिदितामित्यत उपधाया इति वर्तते ॥

(उद्योतः) नियमेन—प्रकृतसूत्रेण ॥ शासिनेति । तस्य स्थानषष्ठीत्वेनोपधाविशेषणे सामर्थ्याभावादिति भावः ॥

(२७४ आक्षेपबाधकसमाधानवार्तिकम् ॥ ३ ॥)

॥ * ॥ अवयवषष्ठ्यादीनां चाऽप्राप्तिर्योगस्यासंदिग्धत्वात् ॥ * ॥

(भाष्यम्)

अवयवषष्ठ्यादीनां च नियमस्याप्राप्तिः ॥

किं कारणम् ?

'योगस्यासंदिग्धत्वात्' । संदेहे नियमः । न चावयवषष्ठ्यादिषु संदेहः ॥

(प्रदीपः) असंदिग्धत्वादिति । अनियमप्रसङ्गे नियमः क्रियते, न तु प्रागेवावस्थिते नियमे ॥

(उद्योतः) भाष्ये—अवयवषष्ठ्यादीनामिति । अवयवषष्ठ्यादीनामिष्टानां निवृत्तये नियमाप्राप्तिरिति वार्तिकार्थः ॥

(आक्षेपभाष्यम्)

किं वक्तव्यमेतत् ?

(समाधानभाष्यम्)

न हि ॥

कथमनुच्यमानं गंस्यते ?

लौकिकोऽयं दृष्टान्तः । तद्यथा लोके—कश्चित् कंचित् पृच्छति—ग्रामान्तरं गमिष्यामि पन्थानं मे भवानुपदिशत्विति । स तस्मायाचष्टे—अमुष्मिन्नवकाशे हस्तदक्षिणो ग्रहीतव्यः, अमुष्मिन्नवकाशे हस्तवाम इति । यस्तत्र तिर्यक्पथो भवति, न तस्मिन् संदेह इति कृत्वा नासावुपदिश्यते । एवमिहापि संदेहे नियमः । न चावयवषष्ठ्यादिषु संदेहः ॥

(प्रदीपः) हस्तदक्षिण इति । हस्तो दक्षिणो यस्येति बहुव्रीहिः । भाष्यकारवचनात्सर्वनाम्नोऽपि परनिपातः ॥

(उद्योतः) दक्षिणो यस्येति । दक्षिणो हस्तो यस्य सन्निहित इत्यर्थः ॥ तिर्यक्पथः—अनृजुमार्ग इत्यर्थः । पूर्वपश्चिमान्यतरदिशि गच्छतो दक्षिणोत्तरमार्ग इति यावत् ॥

(समाधानान्तरभाष्यम्)

अथवा—स्थाने अयोगा-स्थानेयोगा ॥

किमिदमयोगेति ?

अव्यक्तयोगा—अयोगा ॥

(प्रदीपः) अयोगेति । योगमन्तरेण षष्ठ्या एवाऽभावाद्विशिष्टो योगो यस्या नास्तीति सामर्थ्यात्प्रतीयते ॥

(उद्योतः) विशिष्ट इति । निर्णीतविशिष्ट इत्यर्थः । अयमेव भाष्ये व्यक्तशब्दस्यार्थः । अत्र पक्षे योगशब्दः कर्मव्युत्पत्त्या संबन्धिपरः । योगवतीति पक्षेऽप्येवमेव, स्थानरूपसंबन्धिनियमार्थत्वादस्य ॥

(समाधानान्तरभाष्यम्)

अथवा—योगवती-योगा ॥

का पुनर्योगवती ?

यस्या बहवो योगाः ॥

कुत एतत् ?

भूम्नि हि मतुब् भवति ॥

(प्रदीपः) योगवतीति । षष्ठ्या अवश्यंभावी योग इति भूम्नि सामर्थ्याद् मत्वर्थीयोऽकारः ॥

(२७५ आक्षेपबाधकवार्तिकम् ॥ ४ ॥)

॥*॥ विशिष्टा वा षष्ठी स्थानेयोगा ॥*॥

(भाष्यम्)

अथवा किंचिल्लिङ्गमासज्य वक्ष्यामि—इत्थंलिङ्गा षष्ठी स्थानेयोगा भवतीति ॥ न च तल्लिङ्गमवयवषष्ठ्यादिषु करिष्यते ॥

(प्रदीपः) किंचिल्लिङ्गमिति । कलादिकम् ॥

(उद्योतः) विशिष्टा वेति वार्तिकं व्याचष्टे—अथवा किंचिदिति ॥

(आक्षेपभाष्यम्)

यद्येवं, "शास इदङ्हलोः" "शा हौ" शासिग्रहणं कर्तव्यम्—स्थानेयोगार्थं लिङ्गमासङ्क्ष्यामीति ॥

(आक्षेपबाधकभाष्यम्)

न कर्तव्यम् । यदेवादः पुरस्तादवयवषष्ठ्यर्थं प्रकृतम्, एतदुत्तरत्रानुवृत्तं सत् स्थानेयोगार्थं भविष्यति ॥

कथम् ?

अधिकारो नाम त्रिप्रकारः ।

कश्चिदेकदेशस्थः सर्वं शास्त्रमभिज्वलयति, यथा प्रदीपः सुप्रज्वलितः सर्वं वेश्माभिज्वलयति ॥

अपरोऽधिकारः—यथा रज्ज्वा अयसा वा बद्धं काष्ठमनुकृष्यते तद्वदनुकृष्यते चकारेण ॥

अपरोऽधिकारः—प्रतियोगं तस्यानिर्देशार्थ इति योगे योगे उपतिष्ठते ॥

तद्यदैष पक्षः—अधिकारः प्रतियोगं तस्यानिर्देशार्थ इति, तदा हि यदेवादः पुरस्तादवयवषष्ठ्यर्थम्, एतदुत्तरत्रानुवृत्तं सत् स्थानेयोगार्थं भविष्यति ॥

(प्रदीपः) **अधिकारो नामेति** । पारार्थ्यसाम्यात्परिभाषाऽप्यधिकार उच्यते ॥ **कश्चिदिति** । परिभाषारूप इत्यर्थः ॥ **चकारेणेति** । यथा सहस्य स इत्यविशेषेण ग्रन्थान्ताधिके चेत्यादावनुकृष्यते ॥

(उद्द्योतः) भाष्ये—कश्चिदेकदेशस्थ इति । इदं च यथोद्देशपक्षे स्पष्टमेव । कार्यकालेऽपि स्वविषयसर्वशास्त्रैकवाक्यत्वादेवमुक्तिः, पठितदेशस्थेनैव तत्र तत्र तद्बुद्धिजननात् । दीपो यथा प्रभाद्वारा सर्वगृहप्रकाशक एवमेतत्स्वबुद्धिजननद्वारा सर्वशास्त्रोपकारकम् । न तु तत्पक्षेऽप्यचेतनस्य शास्त्रस्य स्वदेशं विहाय तद्देशे गमनमस्तीति बोध्यम् ॥ पठितदेशस्थत्वमेव सर्वथा बोधयितुमेकदेशस्थ इत्युक्तम् ॥ तस्यानिर्देशार्थं इति । अधिक्रियमाणस्यानुच्चारणार्थं इत्यर्थः ॥ यदेवाद इति । शब्दाधिकार आश्रयिष्यत इत्यर्थः ॥

(आक्षेपभाष्यम्)

संप्रत्ययमात्रमेतद्भवति । न ह्यनुच्चार्य शब्दं लिङ्गं शक्यमासङ्क्तुम् ॥

(प्रदीपः) **संप्रत्ययमात्रमिति** । स्वरितत्वप्रतिज्ञानादुत्तरेषु योगेषु तस्य शब्दस्याऽनुमानं भवतु, लिङ्गासङ्गस्त्वनुच्चारितस्य कथं स्यादित्यर्थः ॥

(उद्द्योतः) अनुमानमिति । उच्चारित एव प्रत्यायक इत्युक्तिस्तत्रस्थभाष्यविरुद्धमिदम् । तस्माद्बोद्धुरनुमानपूर्वकमुच्चारणं, न त्वाचार्यस्येत्यर्थः । शास्त्रप्रणयनकालिकतत्कृतलिङ्गासङ्ग एवैतच्छास्त्रप्रवृत्त्युपयोगी नान्यकृतः, अतिप्रसङ्गात् । पाणिनिना त्वनुच्चारणाच्छास्त्रप्रणयनकाले लिङ्गासङ्गः कर्तुमशक्य इति भावः ॥ भाष्ये—संप्रत्ययमात्रमिति । स्वरितत्वबलात्स एवोत्तरत्र - इति ज्ञानमात्रमाचार्यकृतमित्यर्थः ॥ आसङ्क्तुमित्यस्याचार्येणेति शेषः ॥

(आक्षेपबाधकभाष्यम्)

एवं तर्ह्यादेशे तल्लिङ्गं करिष्यते, तत्प्रकृतिमास्कन्त्स्यति ॥

(प्रदीपः) **एवं तर्हीति** । आदेशलिङ्गासङ्गात्तस्य च षष्ठ्यभावात्तत्सम्बद्धस्थानिनो लिङ्गकार्यं फलिष्यतीत्यर्थः ॥

(प्रत्याख्यानभाष्यम्)

यदि नियमः क्रियते, यत्रैका षष्ठी अनेकं च विशेष्यं तत्र न सिध्यति । अङ्गस्य-हलः-अणः-संप्रसारणस्येति हलपि विशेष्यः, अणपि विशेष्यः, संप्रसारणमपि विशेष्यम् ॥ असति पुनर्नियमे कामचारः—एकया षष्ठ्या अनेकं विशेषयितुम् । तद्यथा—देवदत्तस्य पुत्रः पाणिः कम्बल इति । तस्मान्नार्थो नियमेन ॥

(प्रदीपः) **यदीति** । 'अङ्गस्य' इति स्थानषष्ठीत्वाद्विशेषणविशेष्यभावो न प्रकल्पत इत्यर्थः ॥ **देवदत्तस्येति** । संबन्धसामान्यमुपक्रम्यते पश्चात्पदान्तरसन्निधानाद्विशेषावसायः ॥

(उद्द्योतः) (भाष्ये) यदि नियम इति । स्थाननिमित्तसंबन्धार्थकत्वनियम इत्यर्थः ॥ अनेकं विशेष्यं—प्रसङ्गरूपमवयवरूपं च । तत्राद्यं—शा हौ इत्यादौ । अन्त्यं तु भाष्ये एव वक्ष्यति ॥ तत्र न सिध्यतीति । अवयवादिनिमित्तसंबन्धार्थकत्वं न सिध्यतीत्यर्थः ॥ अणपीति । हलः (६।४।२) इति सूत्रे तृतीये दीर्घव्यावृत्त्यर्थमण्ग्रहणस्यापि संबन्धादिति भावः ॥ तत्रालोऽन्त्यस्येत्येकवाक्यतयाऽङ्गावयवाद्धलः परं यदङ्गान्त्यावयवाण्रूपं संप्रसारणं तस्य दीर्घ इति सूत्रार्थः । तत्राङ्गस्येत्यस्य शा हौ इत्यादौ स्थानषष्ठीत्वे हलादिनिरूपितमवयवषष्ठीत्वं न सिध्येदित्यर्थः ॥ स्थानेति । तस्माद्धल इत्यादिनाऽवयववाचकेन विशेषणविशेष्यभावो न स्यादित्यर्थः ॥ विशेषावसाय इति । तत्तदन्वय्यर्थकपदकल्पनयेति भावः ॥

(उक्ताक्षेपस्मारणभाष्यम्)

ननु चोक्तम्—एकशतं षष्ठ्यर्थाः, यावन्तो वा । ते सर्वे षष्ठ्यामुच्चारितायां प्राप्नुवन्तीति ॥

(आक्षेपबाधकभाष्यम्)

नैष दोषः । यद्यपि लोके बहवोऽभिसंबन्धाः— आर्था यौना मौखाः स्रौवाश्च । शब्दस्य तु शब्देन कोऽन्योऽभिसंबन्धो भवितुमर्हति—अन्यदतः स्थानात् ॥

(उद्द्योतः) आर्थाः—स्वस्वामित्वादयः । यौनाः—पितृत्वादयः । मौखः—गुरुशिष्यभावः । स्रौवाः—ऋत्विक्त्वादयः ॥

(आक्षेपसाधकभाष्यम्)

शब्दस्यापि शब्देनानन्तरादयोऽभिसंबन्धाः । अस्तेर्भूर्भवतीति संदेहः—स्थाने-अनन्तरे-समीपे-इति ॥

(उद्द्योतः) स्थानेऽनन्तरे इत्यादि । स्थानादिरूपसंबन्धित्वेनेह इत्यर्थः ॥ आनन्तर्यं—अव्यवधानम् ॥ सामीप्यं—साधारणम् ॥

(आक्षेपबाधकभाष्यम्)

संदेहमात्रमेतद्भवति । सर्वसंदेहेषु चेदमुपतिष्ठते—'व्याख्यानतो विशेषप्रतिपत्तिर्न हि संदेहादलक्षणम्' इति । स्थाने इति व्याख्यास्यामः ॥

(प्रदीपः) **स्थान इति** । अन्तरङ्गत्वाल्लक्ष्यापेक्षणाद्वेति भावः ॥

(उद्द्योतः) अन्तरङ्गत्वादिति । स्थानशब्दोऽर्थवाची प्रसङ्गवाची वा, उभयथाऽप्यन्तरङ्गत्वम् । स्थानिवदादेश इति ज्ञापकमप्यत्र बोध्यम् ॥

(निर्दिश्यमानपरिभाषाधिकरणम्)

(आक्षेपभाष्यम्)

न तर्हीदानीमयं योगो वक्तव्यः ॥

(समाधानभाष्यम्)

वक्तव्यश्च ॥

किं प्रयोजनम् ?

षष्ठ्यन्तं स्थानेन यथा युज्येत यतः षष्ठ्यु-

ह्वरिता ॥

किं कृतं भवति?

'निर्दिश्यमानस्यादेशा भवन्ति' इत्येषा परिभाषा न कर्तव्या भवति ॥ षष्ठी स्थानेयोगा ॥ ४९ ॥

(प्रदीपः) यतः षष्ठीति । तेन पादः पदित्यस्याऽयमर्थः—पादन्तस्याङ्गस्य योऽवयवः पाच्छब्दः सूत्रे षष्ठ्या निर्दिष्टस्तस्य पच्छब्द आदेशो भवति, न तु प्रतीयमानस्य पादन्तस्य । अस्यैव सूत्रस्य निर्दिश्यमानस्यादेशा भवन्तीत्ययमर्थः । षष्ठीति षष्ठ्यन्तं गृह्यते । तेन षष्ठ्यन्तमेव निर्दिश्यमानं स्थानेन युज्यते, न तु प्रतीयमानमित्यर्थः । अलोऽन्त्यस्यादेः परस्येत्येतत्तु वचनसामर्थ्यान्न बाध्यते ॥ ४९ ॥

(उद्योतः) निर्दिश्यमानमिति । उच्चार्यमाणमित्यर्थः । निर्दिश्यमानं षष्ठ्यन्तमेवेत्यन्वयः । निर्दिश्यमानपदस्य चाध्याहार इति भावः ॥ न बाध्यते इति । किंतु स्वव्यवस्थापकत्वेनाश्रीयत इत्यर्थः । एवमनेकाल्सूत्रे सर्वोऽप्येतत्परिभाषाबोधित एव गृह्यते । पेंड्व इत्यादावपि आदेशैः पाणिनिकृतस्थान्युच्चारणानुमानाद्यवस्थार्थत्वाद्वा न दोषः ॥ यत्त्वलोऽन्त्यस्यादेः परस्येत्यम् एतद्बाधकाविति, तत्तु उदस्था इति पादःपदिति सूत्रस्थभाष्यविरुद्धम् । व्यवस्थापकत्वे संभवति बाधकत्वकल्पनाऽनौचित्यग्रस्तं च ॥ ४९ ॥

(४५ अन्तरतमपरिभाषासूत्रम् ॥ १ । १ । ७ आ. ६)

स्थानेऽन्तरतमः ॥ १ । १ । ५० ॥

(सूत्रोदाहरणाधिकरणम्)

(आक्षेपभाष्यम्)

किमुदाहरणम्?

(प्रदीपः) स्थाने० ॥ ५० ॥ किमुदाहरणमिति । कच्चिल्लक्षणान्तरेणेष्टं सिद्धमिति प्रश्नः ॥

(उद्योतः) स्थानेऽन्त० ॥५०॥ इति प्रश्न इति । ऐवंच परोक्तोदाहरणदूषणायायं प्रश्नः, न तूदाहरणासंभवकृत इति भावः ॥

(समाधानभाष्यम्)

"इको यणचि" । दध्यत्र, मध्वत्र । तालुस्थानस्य तालुस्थानः, ओष्ठस्थानस्य ओष्ठस्थानो यथा स्यादिति ॥

(प्रदीपः) इको यणचि दध्यत्रेति । अस्य सूत्रस्य लक्षणमप्युदाहरणं, प्रयोगोऽपि-इत्युभयोपन्यासः ॥ इको ह्रस्वादिभेदात् षट्षष्टिः, यणस्तु सप्त-इति वैषम्यात्संख्यातानुदेशो न सिध्यतीत्यर्थः ॥

(उद्योतः) उदाहरणप्रश्ने इको यणचीत्यस्योल्लेखो व्यर्थोऽत आह—अस्य सूत्रस्येति । सामान्यतो ज्ञातस्य विशेषाकारेण यत्र प्रतिपत्तिस्तदुदाहरणमिति भावः ॥ षट्षष्टिरिति । लवर्णस्य दीर्घाभावात् । दीर्घप्लुतऋकारस्य प्लुतऌकारस्य चानुनासिकस्यादर्शनादिदं चिन्त्यम् ॥ सप्तेति । रेफस्य सानुनासिकस्याभावादिति भावः ॥ इदं चिन्त्यम् । अणुदित्सूत्रेऽण्ग्रहणसामर्थ्येन यणंशे गुणभेदकत्वस्यैव न्याय्यत्वेन विधीयमानत्वेन च तेषामग्रहणात् । तत्प्रत्याख्यानेऽपि आरम्भप्रत्याख्यानयोः फलभेदाय भेदकत्वस्यैवाश्रयणेन तेषामग्रहणम् । अत एव मतोर्मस्य नानुनासिको वकार इति ॥

(समाधानबाधकभाष्यम्)

नैतदस्ति । संख्यातानुदेशेनाप्येतत्सिद्धम् ॥

(प्रदीपः) नैतदस्तीति । प्रत्याहारपाठे शब्दतः साम्यमस्तीति भावः ॥ घस्लादेश इत्यादौ लकारोऽपि ऌकारस्यादेशो दृश्यत इति ऌकारस्य स्थानित्वाभावो नाशङ्कनीयः ॥

(उद्योतः) सङ्ख्यातानुदेशः-क्रमेणान्वयः ॥ शब्दत इति । अयं भावः—यथा स्यतासी लृलुटोरित्यत्रार्थवैषम्येऽपि बोधकशब्दसाम्याद्यथासङ्ख्यम्, तथा इक्पदयणपदाभ्यामनेकोपस्थितावपि बोधकशब्दसाम्यमस्त्येवेति न दोष इति ॥ न च ऋकारे लकारस्य लकारे रेफस्य चापत्तिः । ऋदिद्दृदितोर्भेदेन निर्देशाद् सावर्ण्यानित्यत्वेनात्र ऋलर्णयो न लकारर्कारयोर्ग्रहणमिति नोक्तदोष इति तदाशयात् ॥ ननु ऌकारोदाहरणाभावात्कथं यथासङ्ख्यमत आह—घस्लेति । वस्तुतः प्रतिपत्तिकालिकं सङ्ख्यासाम्यमेव यथासङ्ख्यप्रवृत्तौ नियामकम्, न तु लक्ष्यसंस्कारकालिकमपीति प्रत्याहाराह्निके भाष्ये स्पष्टत्वान्नायं दोष इति बोध्यम् ॥ अनुनासिकस्थाने सानुनासिकार्थमपि न तत्रैतदुपयोगः, विधेयेऽणि गुणभेदकपक्षस्यैव सत्त्वेन तत्र तदप्राप्तेः ॥

(उदाहरणप्रदर्शकभाष्यम्)

इदं तर्हि—"तस्थस्थमिपां तांतंतामः" इति । एकार्थस्यैकार्थः, द्व्यर्थस्य द्व्यर्थः, बह्वर्थस्य बह्वर्थो यथा स्यादिति ॥

(प्रदीपः) एकार्थस्येति । सादृश्यहेतुधर्मोपलक्षणमेतत् । तेन प्रत्यक्त्वादयोऽपि धर्मा गृह्यन्ते ॥

(उद्योतः) आदेशानां तत्स्थानापन्नत्वेन न तदर्थत्वम्, किंतु स्वभावत एव, शब्दार्थसंबन्धानां नित्यत्वात्-इत्याशयेन भाष्ये—एकार्थ इति ॥ तावन्मात्रोक्तौ तसस्तमपि प्राप्नोति थसस्तामपीत्यत आह—सादृश्येति । उत्तमे-प्रत्यक्स्वरूपोऽहंकारास्पदचेतनधर्मः, मध्यमे-अहंकारानास्पदचेतनधर्मः पराक्त्वम्, प्रथमे त्वनियतम् ॥

(उदाहरणबाधकभाष्यम्)

ननु च एतदपि संख्यातानुदेशेनैव सिद्धम् ॥

(उदाहरणान्तरभाष्यम्)

इदं तर्हि-"अकः सवर्णे दीर्घः" इति । दण्डाग्रम्, कूपाग्रम्, दधीन्द्रः, मधूष्ट्रः । कण्ठस्थानयोः कण्ठस्थानः, तालुस्थानयोस्तालुस्थानः, ओष्ठस्थानयोरोष्ठस्थानो यथा स्यात् ॥

(यत्रानेकविधपरिभाषासाधनम्)

(आक्षेपभाष्यम्)

अथ स्थान इति वर्तमाने पुनः स्थानग्रहणं

किमर्थम् ॥

(समाधानभाष्यम्)

यत्रानेकमान्तर्यं तत्र स्थानत एवान्तर्यं बलीयो यथा स्यात् ॥

किं पुनस्तत् ?

चेता, स्तोता । प्रमाणतोऽकारो गुणः प्राप्नोति, स्थानत एकारौकारौ । पुनः स्थानग्रहणादेकारौकारौ भवतः ॥

(प्रदीपः) यत्रानेकमिति । स्थानग्रहणेऽनुवर्तमाने वाक्यभेदः क्रियते—स्थानेऽन्तरतमो भवति, यत्र चानेकमान्तर्यमस्ति तत्र स्थानकृतमेवान्तर्यमाश्रीयत इति । वाक्यभेदस्य च तमग्रहणमेव लिङ्गम् । स्थानकृत एव हि सादृश्ये गृह्यमाणे सादृश्यान्तरपरित्यागात्तमग्रहणमनर्थकं स्यात् ॥

(उद्द्योतः) भाष्ये—अनुवर्तमाने इति । एकदेशे स्वरितत्वप्रतिज्ञानादिति भावः ॥ वाक्यभेद इति । अनुवृत्तप्रसक्तावित्स्थानशब्देनैकं वाक्यम्, ताल्वादिवाचीहत्यस्थानशब्देनापरम् । अत्र च स्थाने इति तृतीयार्थे सप्तमीति भावः ॥ तमग्रहणमनर्थकमिति । 'प्रसङ्गे स्थानकृतान्तर्यवान्' इत्यर्थेनैव सिद्धे स्थानेग्रहणं न वाक्यभेदे मानमितीदमुक्तम् । तथैकवाक्यतायां तु स्थानकृतान्तर्याभावे 'तद्धसति'इत्यादावव्यवस्थैव स्यात् । वाक्यभेदे तु सादृश्यान्तरमादाय तत्र व्यवस्थेति भावः ॥

(तमग्रहणप्रयोजनम्)

(आक्षेपभाष्यम्)

अथ तमग्रहणं किमर्थम् ?

(समाधानभाष्यम्)

"झयो होऽन्यतरस्याम्"इत्यत्र 'सोष्मणः सोष्माणः' इति द्वितीयाः प्रसक्ताः, 'नादवतो नादवन्तः' इति तृतीयाः प्रसक्ताः ॥ तमग्रहणाद्ये सोष्माणो नादवन्तश्च ते भवन्ति चतुर्थाः—वाग्घसति, त्रिष्टुब्भसति—इति ॥

(प्रदीपः) सोष्मण इति । ऊष्मत्वगुणयुक्तस्येत्यर्थः ॥ तमग्रहणादिति । ईषत्सदृशेऽपि लोके सदृशव्यवहारदर्शनादिह तमग्रहणं कृतम् ॥

(उद्द्योतः) ऊष्मत्वेति । सदृशशब्दप्रयोगोपपत्तये धर्मपर ऊष्मशब्द इति भावः ॥

(सूत्रप्रयोजनम्)

(आक्षेपभाष्यम्)

किमर्थं पुनरिदमुच्यते ?

(प्रदीपः) किमर्थमिति । यदीदं नोच्येत किं स्यादिति प्रश्नः ॥

(उद्द्योतः) नन्वनन्यथासिद्धोदाहरणरूपप्रयोजनोक्तेः पुनः प्रश्नानुपपत्तिरत आह—यदीति । सूत्राभावे किमनिष्टमिति प्रश्नतात्पर्यमिति भावः ॥

(२७६ समाधानवार्तिकम् ॥ १ ॥)

॥ * ॥ स्थानिन एकत्वनिर्देशादनेकादेशनिर्देशाच्च सर्वप्रसङ्गस्तस्मात् स्थानेऽन्तरतमवचनं नियमार्थम् ॥ * ॥

(भाष्यम्)

स्थान्येकत्वेन निर्दिश्यते—अक इति । अनेकश्च पुनरादेशः प्रतिनिर्दिश्यते—दीर्घ इति । 'स्थानिन एकत्वनिर्देशादनेकादेशनिर्देशाच्च सर्वप्रसङ्गः' । सर्वे सर्वत्र प्राप्नुवन्ति । इष्यते चान्तरतमा एव स्युरिति । तच्चान्तरेण यत्नं न सिध्यति । 'तस्मात् स्थानेऽन्तरतमवचनं नियमार्थम्' । एवमर्थमिदमुच्यते ॥

(प्रदीपः) स्थानिन इति । यद्यपि 'अकः' इत्यनेन स्थानिनो बहव उपात्तास्तथापि प्रयोगे एकैकः स्थानी, तस्य पर्यायेण बहवो दीर्घा आदेशाः प्राप्नुवन्तीत्यर्थः ॥

(उद्द्योतः) बहव इति । एवं च 'एकत्वनिर्देशात्' इत्यनुपपन्नमिति भावः ॥ प्रयोग इति । अक इत्येतद्बोध्यः स्थानी प्रयोगे एकत्वविशिष्ट उच्चार्यत इति भाष्याक्षरार्थः ॥ यद्यपि पूर्वपरयोरित्युक्तेरेकः स्थानीत्ययुक्तम्, तथापि तत्समुदायाभिप्रायेणेदम् ॥ युगपदेककर्तृकं सर्वोच्चारणमशक्यमत आह—पर्यायेणेति ॥

(काकुभाष्यम्)

अस्ति प्रयोजनमेतत् ॥

किं तर्हीति ?

(अथ प्रथमान्तपाठनिर्णयः)

(आक्षेपभाष्यम्)

यथा पुनरियमन्तरतमनिर्वृत्तिः, सा किं प्रकृतितो भवति—स्थानिन्यन्तरतमे षष्ठीति । आहोस्विदादेशतः—स्थाने प्राप्यमाणानामन्तरतम आदेशो भवतीति ॥

कुतः पुनरियं विचारणा ?

उभयथा हि तुल्या संहिता "स्थानेऽन्तरतम उरण् रपरः" इति ॥

(प्रदीपः) यथा पुनरिति । येन प्रकारेण संहितापाठलक्षणेनेत्यर्थः ॥ प्रतिसूत्रं तु विच्छिद्य पाठे संशयाभावः । पदप्रकृतिः संहितेति संहिताया एव नित्यत्वात्ततः पदापोद्धारे क्रियमाणेऽन्तरतमशब्दः किं सप्तम्यन्तोऽपोद्ध्रियते, अथ प्रथमान्त इति प्रश्नः ॥ तत्र सप्तम्यन्तपक्षे षष्ठीति वर्तते । अन्तरतमो य आदेशस्य स्थानी तत्रैव षष्ठी, यत्रैव षष्ठी तत्रादेश इति प्रकृतिर्नियम्यते । प्रथमान्तपक्षे तु अन्तरतम आदेशो भवतीत्यादेशो नियम्यते ॥

(उद्द्योतः) 'येन प्रकारेण संहितापाठलक्षणेन' इति पाठः । अनेन संहितापाठ एव पूर्वं स्थित इत्युक्तम् ॥ अस्तु तर्हि विच्छिद्य पाठोऽत आह—पदप्रकृतिरिति । षष्ठीतत्पुरुषः ॥ बहुव्रीहिरित्यन्ये । तत्प्रकृतग्रन्थाननुगुणम् ॥ भाष्ये—सा किं प्रकृतित इति । 'सा' इति 'इयं' इत्यस्य प्रतिनिर्देशः । इदंशब्दोऽपि यच्छब्दार्थः क्वचित् । केचित्तु 'यथापुनर्' इति 'या' इत्यर्थेऽव्ययसमुदाय इत्याहुः ॥ अन्तरतमशब्दार्थस्य विशेषणत्वेन या प्रतिपत्तिः सा किं सौत्रस्थानशब्दस्य 'तिष्ठन्त्यस्मिन्नादेशाः' इत्यधिकरणव्युत्पत्त्याऽन्तरतमे स्थानिनीत्यर्थात् स्थानिनं प्रति, उतादेशं प्रतीत्यर्थः ॥ षष्ठीति वर्तत इति । अन्तरतमे—अर्थादादेशस्य स्थानिनि षष्ठी उपसंहर्तव्येत्यर्थः ॥ यत्रैव षष्ठीत्यादि तु पर्यवसितार्थकथनम् ॥

(भाष्यम्)

किं चातः ?

(सप्तम्यन्तपाठदूषणभाष्यम्)

यदि प्रकृतितः-इति, "इको यणचि" इति यणां येऽन्तरतमा इकस्तत्र षष्ठी, यत्र षष्ठी तत्रादेशा भवन्तीति इहैव स्यात्—दध्यत्र, मध्वत्र । कुमार्यर्थम्, ब्रह्मबन्ध्वर्थमित्यत्र न स्यात् ॥

आदेशतः पुनरन्तरतमनिर्वृत्तौ सत्यां सर्वत्र षष्ठी, यत्र षष्ठी तत्रादेशा भवन्तीति सर्वत्र सिद्धं भवति ॥

(प्रदीपः) इहैवेति । यणामर्धमात्रिकाणां सदृशा ह्रस्वा मात्रिकाः, न तु दूरविप्रकृष्टा दीर्घा इति भावः ॥ आदेशनियमपक्षे चैतदुदाहरणत्वेन दूषितम् । प्रकृतिनियमपक्षे तु भवत्येतदुदाहरणम् ॥

(उद्द्योतः) ननु भाष्ये सम्प्रधारणानुद्देशेनैतदुदाहरणस्य दूषितत्वात् पुनरुपन्यासोऽयुक्तोऽत आह—आदेशेति ॥ भवत्येवेति । दीर्घव्यावृत्तये इत्यर्थः ॥

(सप्तम्यन्तपाठदूषणान्तरभाष्यम्)

तथा—"इको गुणवृद्धी" गुणवृद्ध्योर्येऽन्तरतमा इकस्तत्र षष्ठी, यत्र षष्ठी तत्रादेशा भवन्तीति इहैव स्यात्—नेता, लविता, नायकः, लावकः । चेता, स्तोता, चायकः, स्तावक इत्यत्र न स्यात् ॥

आदेशतः पुनरन्तरतमनिर्वृत्तौ सत्यां सर्वत्र षष्ठी, यत्र षष्ठी तत्रादेशा भवन्तीति सर्वत्र सिद्धं भवति ॥

(प्रदीपः) चायक इति । अचोऽञ्णितीत्यत्रापि अयमेव दोष इत्युपन्यासः ॥

(उद्द्योतः) भाष्ये—इको गुणवृद्धी इति । विध्येकवाक्यतापन्नस्य खण्ड इति बोध्यम् ॥ ननु 'इको गुणवृद्धी' इत्युक्त्वा 'चायकः' इत्युदाहरणमसङ्गतमत आह—अच इति । केचित्तु—इको यत्र गुणवृद्धी इष्टे तत्र-इति भाष्यार्थाद् दोष इत्याहुः ॥

(सप्तम्यन्तपाठदूषणान्तरभाष्यम्)

तथा—ऋवर्णस्य गुणवृद्धिप्रसङ्गे गुणवृद्ध्योर्येऽन्तरतमऋवर्णं तत्र षष्ठी, यत्र षष्ठी तत्रादेशा भवन्तीति इहैव स्यात्—कर्ता, हर्ता, आस्तारकः, निपारक इति । आस्तरिता, निपरिता, कारकः, हारक इत्यत्र न स्यात् ॥

आदेशतः पुनरन्तरतमनिर्वृत्तौ सत्यां सर्वत्र षष्ठी, यत्र षष्ठी तत्रादेशा भवन्तीति सर्वत्र सिद्धं भवति ॥

(प्रदीपः) ऋवर्णस्येति । ऋकारस्य ह्रस्वस्यैव गुणः स्यात् दीर्घस्यैव च वृद्धिरिति विशेषप्रदर्शनाय ऋवर्णस्य पृथगुपन्यासः ॥

(उद्द्योतः) ननु ऋकारस्येगचोरन्तर्भावात्पुनरुपन्यासो व्यर्थोऽत आह—ऋकारस्येति । एवं च सप्तम्यन्तच्छेदो लक्ष्यासिद्ध्या दुष्ट इति भावः ॥

(प्रथमान्तपाठदूषणभाष्यम्)

अथादेशतोऽन्तरतमनिर्वृत्तौ सत्यामयं दोषः—"वान्तो यि प्रत्यये" स्थानिनिर्देशः कर्तव्यः—ओकारौकारयोरिति वक्तव्यम्, एकारैकारयोर्मा भूदिति ॥

प्रकृतितः पुनरन्तरतमनिर्वृत्तौ सत्यां वान्तादेशस्य येषु याऽन्तरतमा प्रकृतिस्तत्र षष्ठी, यत्र षष्ठी तत्रादेशा भवन्तीति अन्तरेण स्थानिनिर्देशं सिद्धं भवति ॥

(प्रदीपः) वान्तो यीति । एच इत्यनुवर्तनात् सर्वेषां वान्तादेशप्रसङ्गः ॥ यदा त्वेवं व्याख्यायते—यादृशो वान्त आदेशः पूर्वं दृष्टस्तादृशो यि प्रत्यये भवति । ओकारस्थानिकोऽवादेशो दृष्ट औकारस्थानिकश्चावादेश इति, तदा न दोषः ॥

(उद्द्योतः) यादृश इति । अचीत्यनुवर्त्याचि परतो यस्य यो वान्तो दृष्टस्तस्य यि प्रत्यये स इति व्याख्येयमित्यर्थः ॥ अन्ये तु वाच्यवृत्त्येदृशार्थस्यालाभात् 'यि प्रत्यये' इति इष्टाऽचीत्यस्यासंबन्धाच्च भाष्योक्तं वचनमेव न्याय्य इत्याहुः ॥

(दूषणोद्धारभाष्यम्)

आदेशतोऽप्यन्तरतमनिर्वृत्तौ सत्यां न दोषः ॥

कथम् ?

वान्तग्रहणं न करिष्यते—"यि प्रत्यये" एचोऽयादयो भवन्तीत्येव ॥

(आक्षेपभाष्यम्)

यदि न क्रियते, चेयं - जेयमित्यत्रापि प्राप्नोति ॥

(आक्षेपबाधकभाष्यम्)

"क्षय्यजय्यौ शक्यार्थे" इत्येतन्नियमार्थं भविष्यति—क्षिज्योरेवैच इति ॥

(उद्द्योतः) भाष्ये—क्षिज्योरेवेति । ह्रस्वनिर्देशात् 'क्षी' इति दीर्घान्तस्य 'जै जये' इत्यस्य च नेदं नियातनमिति बोध्यम् ॥

(आक्षेपसाधकभाष्यम्)

तयोस्तर्हि शक्यार्थादन्यत्रापि प्राप्नोति—क्षेयं पापं, जेयो वृषलः ॥

तिव्यापकत्वाद्यत्र साक्षादवर्णस्याण् विधीयते तत्रैवेदमुपतिष्ठत इत्येकादेशस्योपसंख्यानं कर्तव्यमेव ॥

(उद्द्योतः) भाष्येऽगृहीताभिप्रायः समुदायस्यातिरिक्तस्य स्थानित्वेऽपि तदन्तर्गतावयवस्यापि स्थानित्वमादाय ऋस्थानिकत्वमनेनोक्तमित्यभिप्रायवानाह—अवयवग्रहणात्सिद्धमिति चेदिति ॥ रान्तस्येति । रान्तरस्येत्यर्थः ॥

(व्याख्यान्तरे दूषणभाष्यम्)

यदि पुनः—ऋवर्णान्तस्य स्थानिनो रपरत्वमुच्येत । खट्वर्श्यः, मालर्श्यः ॥

नैवं शक्यम् । इह न प्रसज्येत—कर्ता-हर्ता, किरति-गिरति । ऋवर्णान्तस्येत्युच्यते, न चैतदृवर्णान्तम् ॥

(प्रदीपः) **यदि पुनरिति** । उरिति वर्णग्रहणाद्वर्णग्रहणं च सर्वत्र तदन्तविधिं प्रयोजयतीति न्यायादृवर्णान्तग्रहणम् । खट्वर्श्य इत्यत्र च समुदाय ऋवर्णान्तो भवतीति सिद्धं रपरत्वम् ॥ **कर्तेति** । अङ्गस्येति षष्ठी अन्त्यमलमुपसंक्रामतीति ऋवर्णस्य गुणेन भाव्यम् । न च ऋवर्णः-ऋवर्णान्तो भवतीति दोषः ॥ न चेह तदन्तविधिरस्ति, उरणिति भूतानुवादात् । न च प्रदेशेषु तदन्तस्य कार्यम्, अन्त्यस्यैवानुसंहारेण स्थानित्वप्रतिपादनादिति भावः ॥

(उद्द्योतः) **ऋवर्णान्तेति** । शब्दशास्त्रप्रस्तावात् शब्दरूपं विशेष्यमादाय तदन्तविधिरिति भावः ॥ नन्विकाऽङ्गे विशेष्यमाणे तदन्तविधेर्ऋवर्णान्तस्य गुणेन भाव्यमत आह—अङ्गस्येति ॥ षष्ठीति । इगन्ताङ्गान्त्यस्य गुण इति वाक्यार्थ इति भावः ॥ भाष्ये लक्ष्यासिद्धिदोषो ऋवर्णान्तस्येत्यर्थे उक्तः ॥ स्वयं तदर्थासम्भवमप्याह—न चेहेति ॥ **भूतानुवादादिति** । एवंचानुवादे परिभाषाया इव संज्ञाया अप्यप्रवृत्तिः ॥ यद्वा समानविभक्त्यन्तविशेष्यरहितभूतानुवादादित्यर्थः ॥ यत्र हि साक्षादर्थाद्वा विशेषणसमानाधिकरणं विशेष्यमुपादीयते तत्रैव वर्णग्रहणे तदन्तविधिः । गमकं विना शब्दरूपं विशेष्यमादाय तु न तदन्तविधिरिति भावः ॥ न च प्रदेशेष्विति । इह तदन्तविध्यभावेऽपि यदि प्रदेशेषु ऋवर्णान्तस्य षष्ठीनिर्देशेन स्थानित्वं स्यात्ततस्तदनुरोधेनानुवादेऽपि एकदेशद्वारा ऋवर्णान्तं ग्राह्यं, तदपि नास्तीति भावः ॥ इदं चिन्त्यम् । वृद्धिर्यस्येत्यादावीदूदेद्द्विवचनमित्यादौ चानुवादेऽपि संज्ञाप्रवृत्तेः । सर्वत्रेति च शब्दरूपविशेष्यमादाय तदन्तविधौ गमकम् । अतो भाष्योक्त एव दोषः ॥

(दूषणबाधकभाष्यम्)

ननु चैतदपि व्यपदेशिवद्भावेन ऋवर्णान्तम् ॥

(दूषणसाधकभाष्यम्)

अर्थवता व्यपदेशिवद्भावः, न चैषोऽर्थवान् तस्मान्नैवं शक्यम् ॥

न चेदेवम्, उपसंख्यानं कर्तव्यम् ॥ इह च रपरत्वस्य प्रतिषेधो वक्तव्यः—मातुः-पितुरिति ॥

(प्रदीपः) **अर्थवतेति** । यथैव 'इयाय' इत्यत्रैकाच्त्वम्, अर्थस्य हि त्यागोपादानाभ्यां वर्णरूपता धातुरूपता च व्यवस्थाप्यते ॥ **इह चेति** ॥ उपसंख्यानस्यातिव्याप्त्येत्यर्थः ॥ **मातुरिति** । रपरत्वे कृते विभक्तिसकारस्य रुत्वम्, पूर्वस्य **रोरीति** लोपः । **ढ्रलोप** इति दीर्घत्वम् । तत्र मातृरिति प्राप्नोतीति भावः ॥

(उद्द्योतः) भाष्ये—अर्थवतेति । इदमसहायत्वोपलक्षणम् । अत एव 'कुरुते' इत्यादावनर्थकेनापि सः । तत्र हि स टिसंज्ञोपयोगिसहायरहित एवेति दिक् ॥ भाष्ये—इह चेति । एकादेशस्योपसङ्ख्यानमित्यौपसङ्ख्यानिकरपरत्वप्रतिषेधश्च वक्तव्य इत्यर्थः । मातुरित्यादौ तदुपसङ्ख्यानातिव्याप्तेरिति भावः ॥ **मातूरितीति** । ऊँ रपर इति पूर्वोक्तभाष्यप्रयोगविरोधाद् 'ऋत उदिति तपरत्वान्मातूरित्यादौ न दीर्घः' इत्यपास्तं वेदितव्यम् ॥

(समाधानभाष्यम्)

उभयं न वक्तव्यम् ॥

कथम् ?

इह यो द्वयोः षष्ठीनिर्दिष्टयोः प्रसङ्गे भवति, लभतेऽसावन्यतरतो व्यपदेशम् । तद्यथा—देवदत्तस्य पुत्रः-देवदत्तायाः पुत्र इति ॥

(प्रदीपः) **द्वयोरिति** । अवयवावेवात्रापेक्षितपरस्परौ स्थानिनौ । अत एवैकग्रहणं स्थानिभेदादादेशभेदनिवृत्त्यर्थं कृतम् ॥ **अन्यतरत इति** । तृतीयान्तादाद्यादित्वात्तसिः ॥ **तद्यथेति** । एकः पुत्र उभाभ्यामपि यथा व्यपदिश्यते, तथेहापि पूर्वपराभ्यां तत्स्थानिकत्वेनादेशस्य व्यपदेशः । अकआदेस्तु समुदायस्यादेशत्वं, नाण इति-रपरत्वाभावः ॥

(उद्द्योतः) उक्तेऽर्थे गमकमाह—अत एवेति ॥ पञ्चम्यन्तात्तसिल्यर्थासङ्गतेराह—तृतीयान्तादिति ॥ समुदायस्येति । प्रत्येकमादेशत्वे प्रमाणाभावादित्यर्थः ॥

(आक्षेपभाष्यम्)

कथं मातुः-पितुरिति ?

(आक्षेपबाधकभाष्यम्)

अस्त्वत्र रपरत्वम् ॥

(आक्षेपसाधकभाष्यम्)

का रूपसिद्धिः ?

(आक्षेपबाधकभाष्यम्)

"रात्सस्य" इति सकारस्य लोपः, रेफस्य विसर्जनीयः ॥

(उद्द्योतः) भाष्ये—रात्सस्येति । सलोपे रुत्वस्यासिद्धत्वादिति भावः ॥

(आक्षेपसाधकभाष्यम्)

नैवं शक्यम् । इह हि—मातुः करोति-पितुः करोतीति, 'अप्रत्ययविसर्जनीयस्य' इति षत्वं प्राप्नोति ॥

(प्रदीपः) **अप्रत्ययेति** । 'अस्' इत्ययं समुदायः प्रत्ययो

(उद्योतः) पक्षान्तरेऽपि तुल्यत्वान्न गौरवमित्याह—अन्ययेति ॥ दकारस्य नत्वं स्यादिति । अनया परिभाषयेति भावः ॥ वस्तुतस्तु आदेः परस्येत्यनेनान्त्यस्याप्राप्तिः । सूत्रं तु उभयाविरोधेन भिन्न इत्यादौ चरितार्थमिति अत्र प्रयोगे न स्यादेव नत्वमिति उभाभ्यामपि तग्रहणं कर्तव्यमिति भाष्यतात्पर्यम् ॥ एवं च प्रथमान्तच्छेदो निर्दोषः । सप्तम्यन्तच्छेदस्तु दुष्ट एव ॥ अत एव न भूसुधियोरित्यादि चरितार्थम् ॥ नृनरयोर्वृद्धिश्चेति शार्ङ्गरवाद्यन्तर्गणसूत्रे यद्यपि तदा 'नरः–अः' इति व्याख्यानादाधाकारस्यैव वृद्धिरिति न तत्र दोषः । तत्र नृनरयोरित्यावर्तते, एकत्र पञ्चम्यर्थे षष्ठी । पृथगपि वा तौ गणे पठ्येते इति बोध्यम् ॥

(इति प्रथमान्तपाठनिर्णयः)

(अथ स्वतन्त्रविधित्वनिराकरणम्)

(आक्षेपभाष्यम्)

किं पुनरिदं निर्वर्तकम्—अन्तरतमा अनेन निर्वर्त्यन्ते । आहोस्वित् प्रतिपादकम्—अन्येन निर्वृत्तानामनेन प्रतिपत्तिः ?

(प्रदीपः) **किं पुनरिति ।** किं स्वतन्त्रमिदं लक्षणम्, आहोस्विल्लक्षणान्तरेणाभिनिर्वृत्तानामनेन नियमः क्रियते, अथ लक्षणान्तरशेषभूतमिति प्रश्नः ॥

(उद्योतः) अथेति । वाक्यभेदाभेदाभ्यां पक्षद्वयभेद इति बोध्यम् । तत्र तृतीयः सिद्धान्तो भविष्यति ॥

(भाष्यम्)

कश्चात्र विशेषः ?

(२७७ प्रथमपक्षदूषणवार्तिकम् ॥ १ ॥)

॥ * ॥ स्थानेऽन्तरतमे निर्वर्तके स्थानिनिवृत्तिः ॥ * ॥

(भाष्यम्)

स्थानेऽन्तरतमे निर्वर्तके सर्वस्थानिनां निवृत्तिः प्राप्नोति । अस्यापि प्राप्नोति—दधि, मधु ॥

(प्रदीपः) **स्थानिनिवृत्तिरिति ।** दधिशब्दस्य यदि दधिशब्द आदेशः क्रियते, तदा प्रयोजनाभावः । भिन्नरूपस्त्वादेशस्तदर्थस्याप्रत्यायक इति शब्दव्यवहारोत्साद एवेति भावः ॥

(उद्योतः) भिन्नरूप इति । पर्यायो यद्यपि भिन्नरूपस्तदर्थस्य प्रत्यायकश्च, तथापि विनिगमकाभावादुभयोः स्थानित्वमादेशत्वं च वाच्यम् । तथा च सूत्रमनारम्भसमं स्यादिति भावः ॥

(आक्षेपबाधकभाष्यम्)

अस्तु । न कश्चिदन्य आदेशः प्रतिनिर्दिश्यते । तत्रान्तर्यतो दधिशब्दस्य दधिशब्द एव, मधुशब्दस्य मधुशब्द एवादेशो भविष्यति ॥

(प्रदीपः) **अस्त्विति ।** वचनसामर्थ्याच्छब्दव्यवहारस्यानादित्वादिति भावः ॥

(उद्योतः) शास्त्रप्रवृत्तौ हेतुः—वचनसामर्थ्यम् । सदृशादेशे हेतुः—शब्देति ॥

(आक्षेपसाधकभाष्यम्)

यदि चैवम्, क्वचिद्वैरूप्यं तत्र दोषः स्यात्—विसं मुसलं "इण्कोः" इति षत्वं प्राप्नोति ॥

(प्रदीपः) **क्वचिद्वैरूप्यमिति ।** यदि विसशब्दस्य विसशब्द आदेशस्तदा षत्वं नास्ति, न हि तदा सकार आदेशः । यदा तु सकारस्य सकार आदेशस्तदा षत्वप्रसङ्ग इति वैरूप्यप्राप्तिः । अस्तेर्भूरित्यादयस्तु विशेषविहितत्वादस्य बाधकाः ॥

(उद्योतः) भाष्ये—यदि चैवमिति । स्थान्यपेक्षयाऽऽदेशे यत्र वैरूप्यं प्रसक्तं तत्र दोष इत्यर्थः ॥ न हि तदेति । आदेशरूपस्यैव तेन षत्वविधानादिति भावः ॥ यद्वा स्थितिं । तत्कुमपथम् भाष्यकृद्वक्ष्यति—'इमे वर्णाः' इत्यादि ॥ नन्वस्य निर्वर्तकत्वे आर्धधातुकेऽप्यस्त्यादीनामस्त्याद्यादेशाः स्युरिति कुतो नोक्तम् ? किं चानेन सिद्धे तैर्व्यर्थं चेत्यत आह—अस्तेरिति । विषयतिनिवृत्तिस्तत्फलमिति भावः ॥

(आक्षेपान्तरभाष्यम्)

अपि च—इष्टा व्यवस्था न प्रकल्पेत । तद्यथा—तप्ते भ्राष्ट्रे तिलाः प्रक्षिप्ता मुहूर्तमपि नावतिष्ठन्ते । एवमिमे वर्णा मुहूर्तमपि नावतिष्ठेरन् ॥

(प्रदीपः) **अपि चेति ।** पुनरन्येनान्येनाऽऽदेशेन भवितव्यमिति भावः ॥ प्रयोजनमन्तरेण प्रवृत्तौ सत्यामसकृदपि प्रवृत्तिः स्यात् । ततश्च सर्वस्य निवृत्त्यभिमुखत्वात्साधुत्वस्य व्यवस्था नोपपद्यते ॥

(उद्योतः) सदृशादेशविषयेऽपि दोषमाह—भाष्ये—अपि चेति ॥ ननु सदृशादेशे कथमिष्टव्यवस्थाऽसिद्धिरत आह—पुनरिति ॥ ननु लक्ष्ये लक्षणस्येति न्यायविरोधोऽत आह—प्रयोजनमिति । सप्रयोजनशास्त्रप्रवृत्तौ हि प्रथमप्रवृत्त्यैव प्रयोजननिष्पत्तेर्न द्वितीयादिप्रवृत्तिरिति तद्बीजम् ॥ न चेदं प्रकृते-इति भावः ॥ भाष्ये—व्यवस्थेत्यस्य सापेक्षत्वादाह—साधुत्वस्येति ॥ परिनिष्ठितत्वव्याप्यत्वात्साधुत्वस्येति भावः ॥ एवं च दोषान्तमेव शास्त्रं स्यादिति तात्पर्यम् ॥

(द्वितीयपक्षाभ्युपगमभाष्यम्)

अस्तु तर्हि प्रतिपादकम् । अन्येन निर्वृत्तानामनेन प्रतिपत्तिः ॥

(प्रदीपः) **अस्तु तर्हीति ।** निर्वृत्तेषु लक्षणान्तरेणादेशेषु नियमोऽनेन क्रियते । तत्रान्तरतमः साधुर्नान्य इत्यर्थः ॥

(उद्योतः) **निर्वृत्तेष्विति ।** अन्येन निर्वृत्तानां मध्येऽनेनान्तरतमस्यैव साधुत्वप्रतिपत्तिरिति भाष्यार्थ इति भावः ॥

(२७८ आक्षेपवार्तिकम् ॥ २ ॥)

॥ * ॥ निर्वृत्तप्रतिपत्तौ निर्वृत्तिः ॥ * ॥

(भाष्यम्)

निर्वृत्तप्रतिपत्तौ निर्वृत्तिर्न सिध्यति । सर्वे सर्वत्र प्राप्नुवन्ति ॥

(प्रदीपः) निर्वृत्तिरिति । अभिमतस्य शब्दस्येत्यर्थः ॥

(उद्द्योतः) अभिमतस्येति । शास्त्रप्रामाण्यादुभयोरपि पाक्षिकसाधुत्वापत्त्येति भावः ॥

(आक्षेपतात्पर्यप्रश्नभाष्यम्)

किं तदुच्यते—निर्वृत्तिर्न सिध्यतीति ?

न साधीयो निर्वृत्तिः सिद्धा भवति ॥

(आक्षेपतात्पर्यवर्णनभाष्यम्)

न ब्रूमः–निर्वृत्तिर्न सिध्यतीति ॥

किं तर्हि ?

इष्टा व्यवस्था न प्रकल्पेत । न सर्वे सर्वत्रेष्यन्ते ॥

(प्रदीपः) इष्टा व्यवस्थेति । अकः सवर्णे दीर्घ इत्यनेन लक्षणेन यदा सर्वे दीर्घाः कृतास्तदा तेषां साधुत्वं विज्ञातम् । न चानेन तेषामेवासाधुत्वं शक्यं प्रतिपादयितुमिति भावः ॥

(उद्द्योतः) दीर्घादेरिष्टा व्यवस्थाऽनेन भविष्यतीत्यत आह—अक इति । एकप्रमाणबोधितस्य सामान्यविशेषभावाभावे न प्रमाणान्तरेण आत्यन्तिको निरासः शक्यः कर्तुमिति भावः ॥

(प्रत्याक्षेपभाष्यम्)

इदमिदानीं किमर्थं स्यात् ?

(उद्द्योतः) ननु शास्त्रप्रामाण्यादुभयोरपि साधुत्वे इदं व्यर्थं स्यादिति पृच्छति—इदमिदानीमिति ॥

(२७९ प्रत्याक्षेपसमाधानवार्तिकम् ॥ ३ ॥)

॥ * ॥ अनर्थकं च ॥ * ॥

(भाष्यम्)

अनर्थकमेतत्स्यात् । यो हि भुक्तवन्तं ब्रूयात् 'मा भुक्थाः' इति, किं तेन कृतं स्यात् ॥

(उद्द्योतः) उत्तरयति—अनर्थकमिति । 'भुक्थाः' इति निरनुस्वारः पाठः ॥

(आनर्थक्यपरिहारेण समाधानभाष्यम्)

॥ उक्तं वा ॥

किमुक्तम् ?

सिद्धं तु षष्ठ्यधिकारे वचनात् इति । षष्ठ्यधिकारेऽयं योगः कर्तव्यः,—"स्थानेऽन्तरतमः" 'षष्ठीनिर्दिष्टस्य' इति ॥

(प्रदीपः) उक्तं वेति । 'इको गुणवृद्धी' इत्यत्र । यत्र षष्ठी तत्रेदमुपतिष्ठते । तेनैकवाक्यताऽनेन सूत्रेण विधिवाक्यानामिति विधानकाल एवान्तरतम आदेशो विधीयते ॥

(उद्द्योतः) आनर्थक्यं परिहरति—उक्तं वेति ॥ द्वितीयपक्षाऽऽरेदमुपपादयति–एकवाक्यतेति । एवं चेतरस्याविधानमेवेति इष्टव्यवस्थासिद्धिरिति भावः ॥

परे तु—उत्पन्नानामनेन निवृत्तिर्लुगादिनेवेति भावः ॥ एतदाशयमजानान आह—'निर्वृत्तिर्न सिध्यति' इति । तदभ्युपेत्य समाधत्ते—उक्तं वेति । भुक्तवतो भोजनफलसंसर्जातत्वान्निषेधस्य वैयर्थ्येऽपि शास्त्रे वृद्धिरादैच्सूत्रभाष्योक्तशास्त्रप्रामाण्याल्लुगादिनेव जातनिवृत्तिरिति वाशब्देन सूचितमित्याहुः ॥

(अनिष्टनिराकरणम्)

(आक्षेपे वार्तिकांशानुवादः ॥)

॥ प्रत्यात्मवचनं च ॥

(भाष्यम्)

प्रत्यात्ममिति च वक्तव्यम् ॥

किं प्रयोजनम् ?

यो यस्यान्तरतमः स तस्य स्थाने यथा स्यात् । अन्यस्यान्तरतमोऽन्यस्य स्थाने मा भूदिति ॥

(प्रदीपः) प्रत्यात्ममिति । आत्मानमात्मानं प्रतीति समासः । स्थान्यात्मनोऽन्तरतम इत्यर्थः ॥

(उद्द्योतः) आत्मानमिति । अनश्चेति टच् ॥ स्थान्यात्मन इति । स्थानिपदार्थस्येत्यर्थः ॥

(२८० समाधानवार्तिकम् ॥ १ ॥)

॥ * ॥ प्रत्यात्मवचनमशिष्यं स्वभावसिद्धत्वात् ॥ * ॥

(भाष्यम्)

प्रत्यात्मवचनमशिष्यम् ॥

किं कारणम् ?

'स्वभावसिद्धत्वात्' । स्वभावत एतत्सिद्धम् । तद्यथा—समाजेषु–समाशेषु–समवायेषु चाऽऽस्यतामित्युक्ते न चोच्यते—प्रत्यात्ममिति, प्रत्यात्मं चासते ॥

(प्रदीपः) स्वभावसिद्धत्वादिति । तुल्यन्यायतया सूत्रप्रत्याख्यानायैतदुक्तं न तु संबन्धिशब्दत्वादिति ॥ समाजेष्विति । समाजः–उत्सवेषु संघातः । समाशः–सहभोजनम् । समवायः–कस्यांचित् क्रियायां मेलनम् ॥

(उद्द्योतः) नन्वन्तरतमशब्दस्य सदृशार्थकत्वेन तुल्यास्यप्रयत्नमित्यत्रेव संबन्धिशब्दत्वादिति कुतो नोक्तमत आह—तुल्येति ॥ (भाष्ये) प्रत्यात्मं चासत इति । स्वस्वसमाजेष्वेवासत इत्यर्थः ॥ कस्यांचिदिति । धर्मनिर्णयादिक्रियायामित्यर्थः ॥

(सूत्रप्रत्याख्यानाधिकरणम्)

(२८१ प्रत्याख्यानवार्तिकम् ॥ १ ॥)

॥ * ॥ अन्तरतमवचनं च ॥ * ॥

(भाष्यम्)

अन्तरतमवचनं चाशिष्यम् । योगश्चाप्ययमशिष्यः ॥

कुतः ?

स्वभावसिद्धत्वादेव । तद्यथा—समाजेषु-समाशेषु-समवायेषु चास्यतामित्युक्ते नैव कृशाः कृशैः सहासते, न पाण्डवः पाण्डुभिः । येषामेव किंचिदर्थकृतमान्तर्यं तैरेव सहासते ॥

तथा—गावो दिवसं चरितवत्यो यो यस्याः प्रसवो भवति तेन सह शेरते ॥

तथा—यान्येतानि गोयुक्तकानि संघुष्टकानि भवन्ति तान्यन्योन्यमपश्यन्ति शब्दं कुर्वन्ति ॥

(प्रदीपः) नैव कृशा इति । गुणप्रमाणकृतसादृश्यपरिहारेण विद्याद्यर्थकृतमान्तर्यं लोक आश्रीयत इत्यर्थः । एवमिहापि यदीयमथ यः शक्नोति वक्तुं तस्य स्थाने स एव भवति ॥ गाव इति । तिरश्चामप्ययं व्यवहारः संकीर्णानामसंकरलक्षणः । एवं चोदनायां संकीर्णा अप्यादेशा असंकरेण प्रवर्त्स्यन्ति ॥ तथा यानीति । यथा तत्र सादृश्याद्वर्गीभवनं विच्छिन्नसादृश्यानामपि भवति, तथा स्थान्यादेशानां स्थानादिना सादृश्येन वर्गीभवनमित्यर्थः ॥

(उद्योतः) अर्थकृतान्तर्ये सति तदेव प्रयोजकमित्याह—गुणेत्यादि । पाण्डुत्वं-गुणः । कृशत्वादि-प्रमाणम् ॥ विद्यादीति । आदिनोत्सवाशनाद्यर्थित्वब्राह्मणत्वादिजातिधनादिसङ्ग्रहः । एवंच अन्तरतमो भवतीति यत्रानेकविधमिति च न्यायसिद्धमिति भावः ॥ दृष्टान्ते विवक्षितार्थमाह—सङ्कीर्णानामिति ॥ भाष्ये प्रसवः-वत्सः ॥ तेन सह—स्वस्वप्रसवेन सह ॥ शेरत इति । क्षेतिः स्थितौ ॥ एवं चोदनायामिति । अनया रीत्या विधिशास्त्रेऽपीत्यर्थः ॥ युक्तकशब्दो युग्मवाची । संघुष्टकशब्दस्तद्युगवहनादिनाऽत्यन्तपरिचितवाची ॥ अनेनापि ग्रन्थेन यत्रानेकविधमित्यर्थः साधित इत्याहुः ॥ सादृश्यादिति । तत्तद्युगवहनादात्र सादृश्यम् ॥

(दृष्टान्तबाधकभाष्यम्)

एवं तावच्चेतनावत्सु ॥

(दृष्टान्तान्तरभाष्यम्)

अचेतनेष्वपि—लोष्टः क्षिप्तो बाहुवेगं गत्वा नैव तिर्यग्गच्छति, नोर्ध्वमारोहति । पृथिवीविकारः पृथिवीमेव गच्छत्यान्तर्यतः ॥

तथा—या एता आन्तरिक्ष्यः सूक्ष्मा आपस्तासां विकारो धूमः । स धूम आकाशे निवाते नैव तिर्यग्गच्छति, नार्वागवरोहति । अब्विकारोऽप एव गच्छत्यान्तर्यतः ॥

तथा—ज्योतिषो विकारोऽर्चिराकाशदेशे निवाते सुप्रज्वलितं नैव तिर्यग्गच्छति, नार्वागवरोहति । ज्योतिषो विकारो ज्योतिरेव गच्छत्यान्तर्यतः ॥

(प्रदीपः) अचेतनेष्वपीति । न्यायस्य व्याप्तिप्रतिपादनपरमेतत् ॥ अब्विकार इति । अन्तरिक्षे सूक्ष्मः समुद्रोऽस्तीति तद्विकारः सर्वा आप इति काष्ठादिस्थानामपामभिसंयोगात् धूमो विकारः ॥ सूर्यविकारोऽर्चिः सूर्यमेव गच्छति ॥

(उद्योतः) अन्तरिक्षे इति । अन्तरिक्षे भवा आन्तरिक्ष्यः ॥ अत एव निदाघे निशि निरावरणे शयानानां शैत्योपलम्भः ॥ तस्यैव च रविकिरणसंपर्केण मेघरूपतया वायुयोगाद्वृष्टिः ॥ आन्तरिक्ष्याणामपां परम्परया धूमो विकार इति दर्शयति—तद्विकारः सर्वा इति । सूर्यविकार इति । अत एव दावाग्नेर्मध्याह्नादौ सूर्यकरसंपर्कात् शैत्यातिशयो दृश्यते ॥

(सूत्रसत्ताप्राप्तदूषणनिराकरणम्)

(२८२ दूषणवार्तिकम् ॥ १ ॥)

॥ * ॥ व्यञ्जनस्वरव्यतिक्रमे च तत्कालप्रसङ्गः ॥ * ॥

(भाष्यम्)

व्यञ्जनव्यतिक्रमे स्वरव्यतिक्रमे च तत्कालता प्राप्नोति ॥ 'व्यञ्जनव्यतिक्रमे'—दृष्टम्, उप्तम् । आन्तर्यतोऽर्धमात्रिकस्य व्यञ्जनस्याऽर्धमात्रिक इक् प्राप्नोति ॥

(प्रदीपः) लोकव्यवहाराश्रयणेन प्रत्याख्याते सूत्रे तदनाश्रयणेन योगारम्भे दोषमाह—व्यञ्जनेति । व्यतिक्रमः—स्थानित्वेन निवृत्तिः । इदमेव शास्त्रं निर्वर्तकमिति भावः ॥

(उद्योतः) तदनाश्रयणेनेति । मन्दमध्यबुद्ध्यर्थमित्यर्थः ॥ ननु नाऽर्धमात्रिक इगित्यत आह—इदमेवेति ॥ 'कार्याः शब्दाः' इति दर्शने प्रमाणादिना तत्तदन्तरतमवर्णनिर्वर्तकमित्यर्थः ॥ एवं च लोकवेदयोरभावेऽपि एतच्छास्त्रसिद्ध एव स इति भावः ॥

(दूषणबाधकभाष्यम्)

नैव लोके नैव वेदेऽर्धमात्रिक इगस्ति ॥

कस्तर्हि ?

मात्रिकः । योऽस्ति स भविष्यति ॥

(प्रदीपः) नैव लोक इति । नित्याः शब्दा अन्वाख्यायन्ते, निर्वृत्तिपक्षेऽप्युच्चारणस्याशक्यत्वादिति भावः ॥

(उद्योतः) यदुक्तं—'इदमेव' इति तत्राह—नित्या इति ॥ निर्वृत्तिपक्षेऽपीति । 'शास्त्रकार्याः शब्दाः' इति दर्शनेऽपीत्यर्थः ॥ उच्चारणस्येति । तस्य लोकाधीनत्वादिति भावः ॥

(द्वितीयदूषणभाष्यम्)

'स्वरव्यतिक्रमे'—दध्यत्र, मध्वत्र, कुमार्यत्र, ब्रह्मबन्ध्वर्थम् । आन्तर्यतो मात्रिकस्य द्विमात्रिकस्यैको मात्रिको द्विमात्रिको यण् प्राप्नोति ॥

(दूषणबाधकभाष्यम्)

नैव लोके नैव वेदे मात्रिको द्विमात्रिको वा यणस्ति ॥

कस्तर्हि ?

अर्धमात्रिकः । योऽस्ति स भविष्यति ॥

(प्रदीपः) नैव लोक इति । कुक्कुटादिषु द्वे व्यञ्जने, न त्वेकमात्रिकमिति ॥

(२८३ दूषणवार्तिकम् ॥ २ ॥)

॥ * ॥ अक्षु चानेकवर्णादेशेषु ॥ * ॥

(भाष्यम्)

अक्षु चानेकवर्णादेशेषु तत्कालता प्राप्नोति ॥ "इदम इश्" । आन्तर्यतोऽर्धतृतीयमात्रिकस्येदमोऽर्धतृतीयमात्रमिवर्णं प्राप्नोति ॥

(प्रदीपः) अर्धतृतीयमात्रमिति । अत्वैकादेशयोः कृतयोरिश्भाव इति यदा प्रक्रियेति भावः ॥

(उद्द्योतः) इदमस्त्रिमात्रिकत्वेन 'अर्धतृतीयमात्रिकः' इत्ययुक्तमत आह—अत्वेति । परत्वादत्वेऽन्तरङ्गत्वादेकादेशे - इति भावः ॥

(दूषणबाधकभाष्यम्)

नैष दोषः । 'भाव्यमानेन सवर्णानां ग्रहणं न' इत्येवं न भविष्यति ॥

(प्रदीपः) भाव्यमानेनेति । 'नैव लोके' इत्ययं परिहारो नोक्तः । यदा विशेषविहितत्वादत्वमिश्भावेन बाध्यते - इति न्यायस्तदा त्रिमात्रस्य त्रिमात्रः संभवात्स्यादेव । प्लुताप्लुतप्रसङ्गे च प्लुतश्च विषये स्मृत इत्युच्यते । अत्र तु प्लुतस्यैव प्राप्तिः ॥

(उद्द्योतः) प्लुताप्लुतेति । तादृशस्थले हि सपादसप्ताध्यायीस्थेन प्लुतविधौ त्रिपादीस्थप्लुतस्यासिद्धत्वात्तद्विषयेऽप्यनेनैव प्लुतविधौ तदंशेऽनुवादत्वं - अन्यांशे विधित्वं - इति शास्त्रस्य वैरूप्यापत्तिस्तद्बीजम् । शास्त्रं स्वप्लुतविधानेन चरितार्थमिति । प्लुतमात्रविधाने तु तद्विषयकलक्षणवैयर्थ्यापत्त्यांऽशेऽनुवादत्वकल्पना सोढव्यैवं । सामर्थ्येनान्तरतमपरिभाषाबाधकल्पनाऽपेक्षयाऽनुवादत्वस्य युक्तत्वाच्चेति भावः ॥

(२८४ दूषणवार्तिकम् ॥ ३ ॥)

॥ * ॥ गुणवृद्ध्येज्भावेषु च ॥ * ॥

(भाष्यम्)

गुणवृद्ध्येज्भावेषु च तत्कालता प्राप्नोति ॥ खट्वा+इन्द्रः-खट्वेन्द्रः, खट्वा+उदकम्-खट्वोदकम्, खट्वा+ईषा-खट्वेषा, खट्वा+ऊढा-खट्वोढा, खट्वा+एलका-खट्वैलका, खट्वा+ओदनः-खट्वौदनः, खट्वा+ऐतिकायनः-खट्वैतिकायनः, खट्वा+औपगवः-खट्वौपगव इति । आन्तर्यतस्त्रिमात्रचतुर्मात्राणां स्थानिनां त्रिमात्रचतुर्मात्रा आदेशाः प्राप्नुवन्ति ॥

(प्रदीपः) खट्वेन्द्र इति । संज्ञयाऽत्र गुणवृद्ध्योर्भावनम् । संज्ञा च भिन्नकालावपि स्यादिति 'भाव्यमानेन-' इति परिहारस्यात्रासंभवः ॥

(उद्द्योतः) संज्ञा चेति । कार्यकालपक्षेऽपि यथा भाव्यमानत्वाभावस्तथोपपादितं वृद्धिसंज्ञासूत्रे ॥

(दूषणबाधकभाष्यम्)

नैष दोषः । तपरे गुणवृद्धी ॥

(दूषणसाधकभाष्यम्)

ननु च तः परो यस्मात्सोऽयं तपरः ॥

(दूषणबाधकभाष्यम्)

नेत्याह । तादपि परस्तपर इति ॥

(आक्षेपभाष्यम्)

यदि तादपि परस्तपरः, "ऋदोरप्" इहैव स्यात्—यवः, स्तवः । लवः, पव इत्यत्र न स्यात् ॥

(आक्षेपबाधकभाष्यम्)

नैष तकारः ॥

कस्तर्हि ?

दकारः ॥

(आक्षेपसाधकभाष्यम्)

किं दकारे प्रयोजनम् ?

(प्रतिबन्दीभूतं समाधानभाष्यम्)

अथ किं तकारे ?

यद्यसंदेहार्थस्तकारः, दकारोऽपि । अथ मुखसुखार्थस्तकारः, दकारोऽपि ॥

(दूषणवार्तिकशेषभाष्यम्)

'एज्भावे'—कुर्वाते, कुर्वाथे । आन्तर्यतोऽर्धतृतीयमात्रस्य दिसंज्ञकस्यार्धतृतीयमात्र एत्वं प्राप्नोति ॥

(प्रदीपः) एज्भाव इति । प्रत्याहारः "प्लुतावैच इदुतौ" "अनोरौ वा" इत्यादिसंग्रहार्थः । तत्र हि मात्रिक एकार औकारश्च स्यात् ॥

(उद्द्योतः) प्रत्याहार इति । वार्तिके गुणवृद्ध्येज्भावेषु इति द्वन्द्वः, न तु कर्मधारयः । भाष्यविरोधादिति भावः ॥ तत्र हीति । प्रमाणत आन्तर्यादिति भावः ॥

(दूषणोद्धारभाष्यम्)

नैव लोके न च वेदेऽर्धतृतीयमात्र एजस्ति ॥

(२८५ आक्षेपवार्तिकम् ॥ ४ ॥)

॥ * ॥ ऋवर्णस्य गुणवृद्धिप्रसङ्गे सर्वप्रसङ्गोऽविशेषात् ॥ * ॥

(भाष्यम्)

ऋवर्णस्य गुणवृद्धिप्रसङ्गे सर्वप्रसङ्गः । सर्वे गुणवृद्धिसंज्ञका ऋवर्णस्य स्थाने प्राप्नुवन्ति ॥

किं कारणम् ?

'अविशेषात्' । न हि कश्चिद्विशेष उपादीयते—एवंजातीयको गुणवृद्धिसंज्ञ ऋवर्णस्य स्थाने भवतीति । अनुपादीयमाने विशेषे सर्वप्रसङ्गः ॥

(प्रदीपः) ऋवर्णस्येति । अत्र ह्रस्वस्याकार एव गुणः स्यात्, स चेष्यत एव। दीर्घस्य त्वेङौ स्याताम्, तुल्यप्रमाणत्वात्। तथा ह्रस्वस्य दीर्घस्य च सर्वे वृद्धिसंज्ञकाः प्राप्नुवन्ति । समुदायापेक्षया तु सर्वप्रसङ्ग इत्युच्यते ॥

(उद्योतः) नन्वेवं ह्रस्वे सर्वगुणप्रसङ्गस्यानुपपादनादृवर्णमात्रे सर्वप्रसङ्ग इत्यनुपपन्नमत आह—समुदायापेक्षयेति । ऋवर्णीय-ह्रस्वादिसमुदायापेक्षयेत्यर्थः ॥

(२८६ समाधानवार्तिकम् ॥ ५ ॥)

॥ * ॥ न वा ऋवर्णस्य स्थाने रपरप्रसङ्गादवर्णस्यान्तर्यम् ॥ * ॥

(भाष्यम्)

न वा एष दोषः ॥

किं कारणम् ?

'ऋवर्णस्य स्थाने रपरप्रसङ्गात्' । उः स्थाने अण् प्रसज्यमान एव रपरो भवतीत्युच्यते । तत्र ऋवर्णस्यान्तर्यतो रेफवतो रेफवानकार एवान्तरतमो भवति ॥

(प्रदीपः) नवेति । 'उरण् रपरः' इत्यनेन गुणवृद्धिशास्त्रस्यैकवाक्यतायां विधीयमान एवाण् रपरो भवतीति स्थितेः स्थानेऽरारौ गुणवृद्धी भवत इत्यर्थः ॥

(उद्योतः) गुणवृद्धिशास्त्रस्येति । प्रतिलक्ष्यं लक्षणभेदादृवर्णविषयगुणादिशास्त्रस्येत्यर्थः ॥ अन्नान्तस्यैको ऋवर्णस्य रपरोऽण्रूपो गुण इति वाक्यार्थ इति भावः ॥ स्थितेरित्यनेनैकदेशद्वारा स्थानत आन्तर्यमुक्तम् ॥

(२८७ आक्षेपवार्तिकम् ॥ ६ ॥)

॥*॥ सर्वादेशप्रसङ्गस्त्वनेकाल्त्वात् ॥*॥

(भाष्यम्)

सर्वादेशस्तु गुणवृद्धिसंज्ञक ऋवर्णस्य प्राप्नोति ॥

किं कारणम् ?

'अनेकाल्त्वात्' । "अनेकाल्शित्सर्वस्य" इति ॥

(प्रदीपः) सर्वादेश इति । ऋवर्णस्य स्थानेऽरारौ क्रियमाणावलोऽन्त्यस्येत्येतद्बाधेनानेकाल्त्वात्सर्वादेशौ प्राप्नुतः ॥

(उद्योतः) ऋवर्णस्येति । ऋवर्णान्तास्येत्यर्थः ॥ सर्वादेशाविति । तैस्त्वेऽपि समुदायान्तर्वर्तित्वादृवर्णस्य तदादेशत्वमपि खट्वर्श्य इत्यादाविव वक्तुं शक्यमिति भावः ॥

(२८८ समाधानवार्तिकम् ॥ ७ ॥)

॥ * ॥ न वाऽनेकाल्त्वस्य तदाश्रयत्वादृवर्णादेशस्याविघातः ॥ * ॥

(भाष्यम्)

न वा एष दोषः ॥

किं कारणम् ?

'अनेकाल्त्वस्य तदाश्रयत्वात्' । यदाऽयमुः स्थाने, तदाऽयमनेकाल् । अनेकाल्त्वस्य तदाश्रयत्वादृवर्णादेशस्य विघातो न भविष्यति ॥

(प्रदीपः) नवेति । 'अङ्गस्य' इति षष्ठी पूर्वमेवान्त्यमिकमुपसंहियते । ततश्च ऋवर्णस्य स्थानित्वे विज्ञाते रपरत्वमानुपूर्व्या सिद्धत्वात् पूर्वप्रवृत्तमलोऽन्त्यस्येत्युपसंहारं न बाधत इत्यर्थः॥

(उद्योतः) पूर्वमेवेति । अन्यथा ऋवर्णस्थानिकत्वाभावाद्र-परत्वमेव न स्यात् । न च समुदायान्तःपातिऋकाराश्रयेण रपरत्वम् । प्रत्यक्षे ऋवर्णस्थानि[त्वे] चरितार्थस्यानुमानिके प्रवृत्त्ययोगात् । खट्वर्श्य इत्यादौ तु पूर्वपरयोरित्यधिकारात् प्रत्यक्षमेव स्थानित्वमिति भावः ॥ पूर्वप्रवृत्तमिति । उपजीव्यं चेत्यपि बोध्यम् ॥ न बाधते - इत्यत्रानेकाल्शित्सर्वस्येति सूत्रं कर्तृ ॥

(समाधानान्तरभाष्यम्)

अथवा—अनान्तर्यमेवैतयोरान्तर्यम् । एकस्यान्तरतमा प्रकृतिर्नास्ति, अपरस्याप्यन्तरतम आदेशो नास्ति । एतदेवैतयोरान्तर्यम् ॥

(प्रदीपः) अथवेति । निर्वृत्तस्याणो रपरत्वविधानेऽपि न दोष इत्यर्थः ॥ अनान्तर्यमेवेति । न हि स्थानार्थगुणप्रमाणकृतमेवान्तर्यं परिभाषितम्, रूपान्तरेणापि सादृश्यसंभवात्परिग्रहाच्चेति भावः ॥ ऋवर्णस्य मात्रिकस्य मात्रिकोऽकारो गुणोऽन्तरतमोऽस्त्येवेति चेत् । तदर्थस्य यत्नस्याकरणाददोष एव । दीर्घस्य तुल्यप्रमाणत्वादेकारौकारावन्तरतमौ स्त इति चेत् । भवेदेतद् यदा भेदापेक्षा क्रियते । ऋवर्णमात्रस्य ह्रस्वाद्यवान्तरभेदानपेक्षायां स्थानकृतमान्तर्यं न केनचिदस्तीति 'अनान्तर्यमेव-' इत्याद्युक्तम् ॥

(उद्योतः) रेफवतो रेफवानन्तरतम एवेति अथवेत्युक्तमत आह—निर्वृत्तस्येति ॥ परिग्रहाच्चेति । पादवन्तेत्यादौ स्थान्यादेशभावमते वर्णसाम्यकृतस्येति भावः ॥ सदृशसंबन्ध्यभाववत्त्वमुभयोः साधारणधर्मरूपं सादृश्यमिति तात्पर्यम् ॥ यत्नस्येति । परिहारान्तराभिधानरूपस्येत्यर्थः ॥ स्थानकृतमिति । अनान्तर्यमिति भाष्यस्य स्थानकृतान्तरतमाभाव इत्यर्थः ॥

(२८९ समाधानान्तरवार्तिकम् ॥ ८ ॥)

॥*॥ संप्रयोगो वा नष्टाश्वदग्धरथवत्॥*॥

(भाष्यम्)

अथवा नष्टाश्वदग्धरथवत्सह संप्रयोगो भवति । तद्यथा—'तवाश्वो नष्टो ममापि रथो दग्धः, उभौ संप्रयुज्यावहै' इति । एवमिहापि—'तवाप्यन्तरतमा प्रकृतिर्नास्ति, ममाप्यन्तरतम आदेशो नास्ति, अस्तु नौ संप्रयोगः' इति ॥

(प्रदीपः) सम्प्रयोगो वेति । यदा 'स्थानेऽन्तरतमः' इत्येतत्प्रत्याख्यातमित्यर्थः ॥

(उद्योतः) नष्टाश्वदग्धरथवदिति । बहुव्रीहिगर्भद्वन्द्वाद्वतिः ॥ पूर्वोक्तेनाथवेत्यनेन पौनरुक्त्यं परिहरति—यदेति ॥ केचित्तु तत्प्रत्याख्यानेऽपि लोकन्यायेन सदृश एवादेश इत्यर्थः साधितो भगवता - इति प्रत्याख्यानाप्रत्याख्यानयोः को विशेषः? तस्मादनान्तर्य-

स्याभावरूपस्य सादृश्यत्वानङ्गीकारेऽप्याह—नष्टाश्वेति ॥ ऋवर्णस्य स्थानित्वेनावर्णस्यादेशत्वेन ग्रहणसामर्थ्यादसादृश्येऽपि स्थान्यादेशभावः । यथा नष्टाश्वदग्धरथयोरत्यन्तभिन्नयोरपि असदृशयोरपि संप्रयोग इति तात्पर्यमित्याहुः ॥

(समाधानबाधकभाष्यम्)

विषम उपन्यासः ॥ चेतनावत्सु आर्थात्प्रकरणाद्वा लोके संप्रयोगो भवति । वर्णाश्च पुनरचेतनाः, तत्र किंकृतः संप्रयोगः ?

(समाधानसाधकभाष्यम्)

यद्यपि वर्णा अचेतनाः । यस्त्वसौ प्रयुङ्क्ते स चेतनावान् ॥

(एकादेशे दूषणनिराकरणम्)

(२९० आक्षेपवार्तिकम् ॥ ९ ॥)

॥ * ॥ एजवर्णयोरादेशेऽवर्णं स्थानिनोऽवर्णप्रधानत्वात् ॥ * ॥

(भाष्यम्)

एजवर्णयोरादेशेऽवर्णं प्राप्नोति । खट्वैलका, मालौपगवः ॥

किं कारणम् ?

'स्थानिनोऽवर्णप्रधानत्वात्' । स्थानी ह्यत्रावर्णप्रधानः ॥

(प्रदीपः) अवर्णप्रधानत्वादिति । इममेव हि न्यायमाश्रित्योक्तम्—ऐचोश्चोत्तरभूयस्त्वादिति ॥

(उद्द्योतः) प्रधानत्वं - भूयस्त्वेन ॥

(२९१ समाधानवार्तिकम् ॥ १० ॥)

॥ * ॥ सिद्धं तूभयान्तर्यात् ॥ * ॥

(भाष्यम्)

सिद्धमेतत् ॥

कथम् ?

'उभयान्तर्यात्' । उभयोर्योऽन्तरतमस्तेन भवितव्यम् । न चावर्णमुभयोरन्तरतमम् ॥ स्थानेऽन्तरतमः ॥ ५० ॥

(प्रदीपः) उभयान्तर्यादिति । छत्रशासने ऐचः समुदायान्तरतमाभावादैचोश्चेत्युक्तम् । इह तु संभवत्येव स्थानेन समुदायान्तरतम इत्यर्थः ॥ ५० ॥

(उद्द्योतः) भूयस्त्वन्यायस्तर्हि केत्यत आह—इहेति ॥५०॥

———

(४९ परिभाषासूत्रम् ॥ १ । १ । ७ आ. ७ ॥)

उरण् रपरः ॥ १ । १ । ५१ ॥

(सूत्रस्य रपरत्वमात्रविधायकत्वम्)

(पक्षद्वयोपस्थापकभाष्यम्)

किमिदमुरण्रपरवचनमन्यनिवृत्त्यर्थम्—'उः स्थाने अणेव भवति रपरश्च' इति । आहोस्विद्रपरत्वमात्रमनेन विधीयते—'उः स्थाने अण् च अनण् च । अण् रपरः' इति ?

कश्चात्र विशेषः ?

(प्रदीपः) उरण्० ॥ ५१ ॥ किमिदमिति । षष्ठीप्रकरणाद्यत्र षष्ठी तत्रेदमुपतिष्ठते । तत्र किमादेशान्तराणां बाधकमणं निर्वर्तयति, तस्य च वाक्यभेदेन रपरत्वम् । आहोस्विद्रपरत्वमात्रमनेन क्रियते, उः स्थाने लक्षणान्तरेण निष्पन्नो योऽण् स रपर इति प्रश्नः ॥ तत्र केषांचित्पाठः—अण् भवति रपरश्चेति । तत्रापूर्वोऽण् विधीयमान आदेशान्तराणां बाधकः । अन्येषां तु पाठः—अणेव भवतीति । तत्र सामर्थ्यादाऽन्यनिवृत्तिः सैवैवकारेण प्रदर्श्यते ॥

(उद्द्योतः) उरण् र० ॥ ५१ ॥ भाष्ये—उरण्रपरवचनमिति । सूत्रस्थविसर्गप्राग्भागानुकरणेन षष्ठीसमासः ॥ नन्वन्यशब्देन न स्थानी, आदेशस्य स्थानिनिवर्तकत्वस्वभावत्वात् । न स्थानिव्यतिरिक्तः, उरणित्येतावतः स्थानिव्यतिरिक्तनिवर्तने सामर्थ्याभावादत आह—षष्ठीति । यत्र षष्ठ्या ऋवर्णस्यादेशप्रसक्तिस्तत्रेत्यर्थः । स्वातन्त्र्येणास्य विधायकत्वं तु 'इको गुणवृद्धी' इत्यत्र भाष्ये एव निराकृतम् । तत्र यद्यन्यनिवृत्त्यर्थत्वं नियामकत्वेन, तदा अथ मतमेतदिति वक्ष्यमाणस्य विक्षेपो न स्यादत आनुषङ्गिकं तदित्याह—तत्रेति ॥ अपूर्व इति । वाक्यभेदेन—ञ्नित्यादिरुदात्तो भवति, ऋवर्णस्य स्थाने अण् भवति स च रपरः—इत्यर्थ इति भावः ॥ तत्र सामर्थ्यादिति । विशेषविधेः सामान्यविधिबाधकत्वेनेत्यर्थः । न तु वाक्यवृत्त्याऽस्य नियमपरत्वमिति भावः ॥

(२९२ प्रथमपक्षाक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ उरण्रपरवचनमन्यनिवृत्त्यर्थं चेदुदात्तादिषु दोषः ॥ * ॥

(भाष्यम्)

उरण्रपरवचनमन्यनिवृत्त्यर्थं चेदुदात्तादिषु दोषो भवति ॥

के पुनरुदात्तादयः ?

उदात्तानुदात्तस्वरितानुनासिकाः । कृतिः - हृतिः, कृतं - हृतम्, प्रकृतं - प्रहृतम्, नॄँः पाहि ॥

(प्रदीपः) उदात्तादिष्विति । अन्तरतमस्य बाधकोऽण् प्रसज्यत इति भावः । स तूदात्तादिगुणो न चेति सर्वथा दोषः ॥ नॄँः पाहीति । यद्यप्यस्मिन् पक्षे पूर्वसवर्णे ऋकारो न लभ्यते, तथापि 'नॄन् पे' इति निपातनाद्भवति । नकारस्य तु रुत्वे कृतेऽनुनासिको विधीयमानोऽणेव स्यान्न तु ऋकार इति दोषः ॥ प्रतिपदविहितैरित्वोत्वादिभिरयं बाध्यत इति तेषां रपरत्वं न स्यात् ॥

(उद्द्योतः) स चोदात्तादिगुण इति । अत्र यतोऽन्तरस्येति न्यायेनान्तरतमपरिभाषाया अनेन बाध इति भावः ॥ न चेति । यत्रोपस्थितिस्तद्विधेयस्य बाध इत्यभिमानः । भाष्ये—कृतिः—नित्स्वरेणाद्युदात्तः । कृतं—इत्यत्र प्रत्ययस्वरेणान्तोदात्तत्वे

शेषनिघातेन ऋकारोऽनुदात्तः । प्रकृते–गतिरनन्तर इति पूर्वपदप्रकृतिस्वरे शेषनिघाते उदात्तादनुदात्तस्येति स्वरितत्वम् । उच्चैरुदात्त इत्यादिषु षष्ठ्यन्तमच इत्यनुवर्तत इति पक्षे ञ्नित्यादिर्दावच इत्यपस्थितेः षष्ठीसद्भावादुरणित्यस्योपस्थानमिति द्रष्टव्यम् । नियमपक्षे वक्ष्यमाणं दोषमत्राप्याकृष्य दर्शयति—प्रतिपदेति । तेषामिति । प्रत्यासत्त्योरणित्यनेन विधीयमानस्याणो विधीयमानमिति शेषः

(द्वितीयपक्षाभ्युपगमभाष्यम्)

अस्तु तर्ह्युः स्थानेऽण् चानण् च । अण् रपर इति ॥

(२९३ द्वितीयपक्षदूषणवार्तिकम् ॥ २ ॥)

॥ * ॥ य उः स्थानेऽण् स रपर इति चेत् गुणवृद्ध्योरवर्णाप्रतिपत्तिः ॥ * ॥

(भाष्यम्)

य उः स्थाने अण् स रपर इति चेद् गुणवृद्ध्योरवर्णस्याप्रतिपत्तिः । कर्ता-हर्ता-वार्षगण्यः ॥

(प्रदीपः) गुणवृद्ध्योरिति । भूतस्य चेदणो रपरत्वं क्रियते, तदा गुणवृद्धिविधावणेव दुर्लभ इति दोषः ॥

(उद्द्योतः) दुर्लभ इति । ह्रस्वस्य गुणाकारलाभेऽपि दीर्घस्याकारगुणालाभः, वृद्धिस्तु नियमेन अण् न लभ्यते इत्यर्थः ॥ कर्त्रेत्याद्युदाहरणं भाष्ये दीर्घान्तस्याप्युपलक्षणम् ॥

(द्वितीयपक्षदूषणशेषाक्षेपभाष्यम्)

किं हि साधीयः—ऋवर्णस्यासवर्णे यदवर्णं स्यात्, न पुनरेङैचौ ?

(प्रदीपः) किं हि साधीय इति । किं साधुतरं कारणमित्यर्थः ॥ न पुनरिति । ततश्चावर्णस्यैव नियमेनाप्रतिपत्तिरिति व्याख्येयम् ॥

(उद्द्योतः) 'किं' इत्यस्य विशेष्यमाह—कारणमिति । भाष्ये-असवर्णे–सदृशाभावे इत्यर्थः ॥ ननु नियामकाभावे कदाचिदवर्णस्यापि प्रतिपत्तौ कथमवर्णाप्रतिपत्तिरत आह—ततश्चेति ॥

(द्वितीयपक्षवादिभाष्यम्)

पूर्वस्मिन्नपि पक्षे एष दोषः । किं हि साधीयः–तत्रापि ऋवर्णस्यासवर्णे यदवर्णं स्यात्, न पुनरिवर्णोवर्णौ ॥

(प्रथमपक्षवादिभाष्यम्)

अथ मतमेतत्—उः स्थाने अणश्चानणश्च प्रसङ्गे अणेव भवति रपरश्चेति । सिद्धा पूर्वस्मिन् पक्षे अवर्णस्य प्रतिपत्तिः ॥

(प्रदीपः) अथ मतमिति । स एव पक्षाक्षेपवाद्याह—नानेनान्येषां बाधकोऽपूर्वोऽण् विधीयते । किं त्वणनणोः प्रसङ्गेऽणेव भवतीति नियमः क्रियते, स च रपरः । न च गुणवृद्धिप्रसङ्गे इकारोकारयोः प्राप्तिः ॥

(उद्द्योतः) दोषपरिहारायाक्षेपवाद्येवान्यनिवृत्त्यर्थमित्यस्य नियमपरतया व्याख्यानमाशङ्क्य दूषयति—भाष्ये—अथ मतमिति । एतत्–वक्ष्यमाणं नियमरूपत्वमन्यनिवृत्त्यर्थमिति वदतो मतं–संमतं विवक्षितमित्यर्थः ॥ सिद्धा पूर्वस्मिन्निति । अन्यनिवृत्त्यर्थमिति पक्षे इत्यर्थः ॥ स चेति । वाक्यभेदेनेत्यर्थः ॥ नन्वेवमिकारोकारावपि स्यातामत आह—न च गुणेति ॥

(आक्षेपभाष्यम्)

यत्तु तदुक्तम्—'उदात्तादिषु दोषः' इति । स इह दोषो जायते, न जायते ?

(प्रदीपः) यत्तु तदुक्तमिति । किं भवान्मन्यते–इति विचारयति ॥

(उद्द्योतः) भवानिति । नियमपक्षवादीत्यर्थः ॥

(समाधानभाष्यम्)

जायते स दोषः ॥

कथम् ?

उदात्त इत्यनेनाणोऽपि प्रतिनिर्दिश्यन्ते, अनणोऽपि ॥

(प्रदीपः) स एव युक्तियुक्तं पक्षं गृह्णाति—जायत इति ॥

(उद्द्योतः) स एवेति । विचारक एवेत्यर्थः ॥

(समाधानबाधकभाष्यम्)

यद्यपि—अणोऽपि प्रतिनिर्दिश्यन्ते । न तु प्राप्नुवन्ति ॥

किं कारणम् ?

स्थानेऽन्तरतमो भवतीति ॥

(उद्द्योतः) शङ्कते—भाष्ये—यद्यप्यणोऽपीति ॥

(समाधानसाधकभाष्यम्)

कुतो नु खल्वेतत्—द्वयोः परिभाषयोः सावकाशयोः समवस्थितयोः—"स्थानेऽन्तरतमः" इति "उरण् रपरः" इति च, 'स्थानेऽन्तर–' इत्यनया व्यवस्था भविष्यति, न पुनः "उरण् रपरः" इति ?

अतः किम् ?

अत एष दोषो जायते '—उदात्तादिषु दोषः' इति ॥

(प्रदीपः) कुतो नु खल्विति । अन्तरतमपरिभाषाया अयमवकाशः—अकः सवर्णे दीर्घः, झयो होऽन्यतरस्यामिति । उरण् रपर इत्यस्यावकाशः–कर्ता-हर्तेति । इहोभयं प्राप्नोति—कृतिरिति । परत्वादियमेव प्राप्नोतीति दोषः ॥

(उद्द्योतः) परिहरति—कुतो न्विति । तमब्ग्रहणसहितस्याप्यवकाशप्रदर्शनाय झयो ह इत्युक्तम् ॥ उरणरपर इत्यस्यावकाश इति । गुणविधौ स्थानेऽन्तरतमपरिभाषाऽनुपस्थितिः, ऋवर्णसमुदायान्तरतमगुणाभावादिति भावः ॥ यद्यपि भाष्याद्विनिगमनाभावो लभ्यते, तथापि एष दोषो जायत इत्युत्तरग्रन्थासङ्गतेर्विनिगमकं प्रदर्श्यान्तरतमपरिभाषाऽप्रवृत्तिमुपपादयति—परत्वादिति ॥

(आक्षेपभाष्यम्)

ये चाप्येते ऋवर्णस्य स्थाने प्रतिपदमादेशा उच्यन्ते, तेषु रपरत्वं न प्राप्नोति—"ऋत इद्धातोः" "उदोष्ठ्यपूर्वस्य" इति ॥

(प्रदीपः) **ये चाप्येत इति ।** यत्र ह्यनियमप्रसङ्गेऽनेन नियमः क्रियते तत्र तच्छेषभूतं रपरत्वं भवति, न त्वन्यत्र प्रतिपदविधाविति दोषः ॥

(उद्द्योतः) ननु प्रतिपदविहिता अप्यण एवेति कुतो रपरत्वाप्राप्तिरत आह—**यत्र हीति** ॥ प्रो यङीति लत्वविधानादाक्षस्या तेषामपि रपरत्वमिति चेत्, ऋकारान्तर्गतरेफस्य लत्वार्थं तत्स्यादिति न दोषः ॥ भाष्ये—**ये चाप्येत इति ।** बहुवचनेनापृञ्च्यृधामिति इत्वसंग्रहः ॥

(२१४ समाधानवार्तिकम् ॥ ३ ॥)

॥ * ॥ सिद्धं तु प्रसङ्गे रपरत्वात् ॥ * ॥

(भाष्यम्)

सिद्धमेतत् ॥

कथम् ?

'प्रसङ्गे रपरत्वात्' । उः स्थाने अण् प्रसज्यमान एव रपरो भवति ॥

(प्रदीपः) **सिद्धं त्विति ।** विधिवाक्यैरस्यैकवाक्यतायां विधानकाल एवाणो रपरत्वं क्रियत इत्यर्थः ॥

(उद्द्योतः) **विधीति ।** ऋवर्णस्थानिकाण्विधिवाक्यैरित्यर्थः ॥ एकवाक्यतायामिति । वाक्यैकवाक्यतायामित्यर्थः ॥

(आक्षेपभाष्यम्)

किं वक्तव्यमेतत् ?

(समाधानभाष्यम्)

न हि ॥

कथमनुच्यमानं गंस्यते ?

'स्थाने' इति वर्तते । स्थानशब्दश्च प्रसङ्गवाची ॥

(आक्षेपभाष्यम्)

यद्येवमादेशोऽविशेषितो भवति ॥

(प्रदीपः) **यद्येवमिति ।** न ह्यनेनोः स्थानेऽण् विधीयते, अपि तु लक्षणान्तरेण । तत्र विध्यङ्गभूता **षष्ठी स्थानेयोगेति** परिभाषा नोपतिष्ठते । तथा च '**उदीचामातः स्थाने यकपूर्वायाः**' इत्यत्र स्थानग्रहणं कृतम् । तत उः समीपे योऽण् तस्यापि रपरत्वप्रसङ्ग इति स्थानग्रहणानुवृत्त्या स्थाने य आदेशोऽणित्येतावल्लभ्यते, न तु प्रसज्यमान इति ॥ **आदेश इति ।** प्रसज्यमानत्वेनेत्यर्थः । **अथवा**-स्थानग्रहणानुवृत्त्या 'प्रसज्यमानः' इत्येषोऽर्थो लभ्यते, न तु-उः स्थान इति । ततश्चाण आदेशरूपता नियमेन न लभ्यते इति सामीप्यलक्षणोऽपि संबन्धोऽवगम्येतेत्यर्थः ॥

(उद्द्योतः) ननु 'उः' इति षष्ठ्या स्थानेयोगत्वस्य लाभः स्यादत आह—**न हीति ।** एवंचायमनुवाद इति भावः ॥ **विध्यङ्गेति ।** विधेयेन साक्षाद्यत्र संबन्धस्तत्र सा परिभाषेत्यर्थः ॥ **उदात्तस्वरितयोर्यणो लः परस्मैपदमित्यादावनुवादेऽप्यस्याः प्रवृत्तेर्यथैव**-मित्यादिभाष्यमेकदेशिनोक्तिरिति बोध्यम् ॥ **उःसमीप इति ।** तथा च 'तृतीयः' इत्यादावप्यणो रपरत्वप्राप्तिरित्यर्थः ॥ सामीप्यं चेषद्व्यवहितेऽपीति भावः ॥ **स्थाने य आदेशोऽणिति ।** अनुवर्तमानस्थानेग्रहणं 'उः' इत्यस्य संबन्धिशब्दत्वात्तत्रैव संबध्येतेत्यर्थः ॥ नन्वेवमादेशः स्थानेन विशेषित एवेति **आदेशोऽविशेषित** इति भाष्यासङ्गतिरित्यत आह—**प्रसज्यमानत्वेनेति ॥ अथवा स्थानेति ।** स्थानशब्दस्य प्राधान्याद् रपर इत्यनेन संबन्ध इति भावः ॥ **तत इति ।** अणः स्थानेपदार्थेनाविशेषणादित्यर्थः ॥ एवंच नादेशान्तराणां बाधकोऽण्विधीयते, नापि नियमः, नापि विहितस्य रपरत्वम्, प्रसज्यमानत्वेन विशेषणात् । किं तु तत्तद्विधिभिर्वाक्यैकवाक्यतैवास्येति बोध्यत इति बोध्यम् ॥

(समाधानभाष्यम्)

आदेशश्च विशेषितः ॥

कथम् ?

द्वितीयं स्थानग्रहणं प्रकृतमनुवर्तते । तत्रैवमभिसंबन्धः करिष्यते—'उः स्थाने अण् स्थाने' इति । उः प्रसङ्गे अण् प्रसज्यमान एव रपरो भवति ॥

(प्रदीपः) **द्वितीयमिति ।** तच्चार्थात् प्रथमान्तं संपद्यते, अथवा सप्तम्यन्त एव तस्मिन्नयमर्थो भवति—प्रसङ्ग एवात्राण् रपरो भवतीति । इदानीमुदात्तादिषु दोषो नास्ति, **स्थानेन्तरतम** इत्यनया परिभाषया कृतिरित्यादावृकारस्य ऋकार एव प्रवर्तत इत्यणः प्रसङ्ग एव नास्ति । गुणवृद्धी च ऋकारस्य विधीयमाने अरारावेवान्तरतम्याद्भवत इत्यवर्णप्रतिपत्तिरप्यस्ति ॥

(उद्द्योतः) **अथवेति ।** स्थानपदेन प्रसङ्गकालो लक्ष्यत इति भावः ॥ **ऋकार एवेति ।** स्थानतः प्रमाणतः स्वरूपतश्च सदृशत्वादिति भावः ॥

(अण्ग्रहणप्रयोजनम्)

(आक्षेपभाष्यम्)

अथाण्ग्रहणं किमर्थम्, न ऊः रपरो भवतीत्येवोच्येत ?

(प्रत्याक्षेपभाष्यम्)

'ऊः रपरः' इतीयत्युच्यमाने क इदानीं रपरः स्यात् ?

(प्रत्याक्षेपसमाधानभाष्यम्)

य उः स्थाने भवति ?

कश्च उः स्थाने भवति ?

आदेशः ॥

(२९५ आक्षेपबाधकवार्तिकम् ॥ १ ॥)

॥ * ॥ आदेशो रपर इति चेद्रीरिविधिषु रपरप्रतिषेधः ॥ * ॥

(भाष्यम्)

आदेशो रपर इति चेद्रीरिविधिषु रपरत्वस्य प्रतिषेधो वक्तव्यः ॥

के पुना रीरिविधयः ?

अकङ्लोपाऽऽनङनङ्रीङ्रिङादेशाः ॥

अकङ्—सौधातकिः । अकङ् ॥

लोप—पैतृष्वसेयः । लोप ॥

आनङ्—होतापोतारौ । आनङ् ॥

अनङ्—कर्ता-हर्ता । अनङ् ॥

रीङ्—मात्रीयति-पित्रीयति । रीङ् ॥

रिङ्—क्रियते-ह्रियते । रिङ् ॥

(प्रदीपः) रीरिविधिष्विति बहुवचननिर्देशात् रीरिशब्दाद्युपलक्षणमिति पृच्छति—के पुनरिति ॥ पैतृष्वसेय इति । लोपवचनं तु सर्वादेशार्थं स्यात् ॥ होतापोताराविति । रेफस्य संयोगान्तलोपे कृते तस्यासिद्धत्वान्नलोपो न स्यात् ॥

(उद्योतः) ननु वार्तिकोक्तरीरिविध्योर्शातत्वात्तस्य चोपलक्षणत्वे प्रमाणाभावात् के पुनरिति प्रश्नानुपपत्तिरत आह—बहुवचनेति ॥ सौधातकौ 'सुधातुरकङ् च' इति इञ् ॥ पैतृष्वसेये ढकि लोपः, तत एव ढक् च ॥ ननु लोपस्य रपरत्वे तं विनाऽपि अणादेशेन तत्साध्यरूपसिद्धिरत आह—लोपेति । रपरत्वाभिधानमुखेन सर्वादेशत्वमेवं लोपस्याभिधित्सितमिति भावः ॥ यदि सर्वादेशो लोपस्तदा उः स्थाने नेति कथं रपरत्वमितीदं चिन्त्यम् । तस्माल्लोपविधिवैयर्थ्यापादनमेव दोष इति तत्त्वम् ॥ आनङनङौ 'आनङृतो द्वन्द्वे' 'ऋदुशन—' इति विहितौ ॥ रेफस्येति । हलग्रहणापकर्षणः प्रतिषेधारम्भाच्च चिन्त्यमिदम् । तस्माद्रेफश्रवणमेव दोषोऽत्रेति बोध्यम् ॥

(आक्षेपबाधकं भाष्यवार्तिकम्)

॥ उदात्तादिषु च ॥

(भाष्यम्)

किम् ?

रपरत्वस्य प्रतिषेधो वक्तव्यः । कृतिः, हृतिः । कृतं, हृतम् । प्रकृतम्, प्रहृतम् । नॄः पाहि ॥ तस्मादणग्रहणं कर्तव्यम् ॥

(एकादेशे रपरत्वसाधनम्)

(२९६ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ एकादेशस्योपसंख्यानम् ॥ * ॥

(भाष्यम्)

एकादेशस्योपसंख्यानं कर्तव्यम् । खट्वर्श्यः, मालर्श्यः ॥

किं पुनः कारणं न सिध्यति ?

उः स्थाने अण् प्रसज्यमान एव रपरो भवतीत्युच्यते । न चायमुरेव स्थानेऽण् शिष्यते ॥

किं तर्हि ?

उश्चान्यस्य च ॥

(प्रदीपः) एकादेशस्येति । 'पूर्वपरयोः' इति समुदायस्य स्थानित्वेन चोदितत्वात्तस्य च ऋवर्णरूपत्वाभावादिति भावः ॥

(उद्योतः) समुदायस्येति । द्वन्द्वस्य सत्त्वादिति भावः ॥

(समाधाने वार्तिकांशानुवादः)

॥ अवयवग्रहणात्सिद्धम् ॥

(भाष्यम्)

यदत्र ऋवर्णं तदाश्रयं रपरत्वं भविष्यति । तद्यथा—'माषा न भोक्तव्याः' इत्युक्ते मिश्रा अपि न भुज्यन्ते ॥

(प्रदीपः) अवयवग्रहणादिति । पूर्वपरयोरित्यनेनोद्भूतावयवभेदः समुदायो निर्दिश्यते । अवयवावेव चापेक्षितपरस्परौ समुदाय इति भवत्ययमृवर्णस्य स्थान इति भावः ॥

(उद्योतः) उद्भूतेति । अत एव द्विवचननिर्देशः । तत्सामर्थ्यादेव प्रत्येकं स्थानित्वबुद्धिरिति भावः ॥ नन्ववयवभेदस्योद्भूतत्वविवक्षा नाम तद्गतसङ्ख्यायाः समुदाये आरोपः, नैतावता प्रत्येकं स्थानित्वलाभोऽत आह—अवयवावेव चेति । इतरेतरयोग इति शेषः ॥ एवंच तत्र समुदायस्यावयवाभेदेन बोधनाद् द्विवचनेन प्रत्येकं तयोः स्थानित्वलाभः ॥ अयमेव चोद्भूतावयवभेदः समुदाय इत्यस्यार्थ इति भावः ॥

(२९७ समाधाननिरासवार्तिकम् ॥ २ ॥)

॥ * ॥ अवयवग्रहणात्सिद्धमिति चेदादेशे रान्तप्रतिषेधः ॥ * ॥

(भाष्यम्)

अवयवग्रहणात्सिद्धमिति चेदादेशे रान्तस्य प्रतिषेधो वक्तव्यः । होतापोतारौ । यथैव-उश्चान्यस्य च स्थानेऽण् रपरो भवति, एवं य उः स्थानेऽण् चानण् च सोऽपि रपरः स्यात् ॥

(प्रदीपः) रान्तप्रतिषेध इति । आनङि विधीयमाने आकारस्याणो भावादित्यर्थः ॥ तस्मादनवयवग्रहणादित्यस्या-

(आक्षेपबाधकभाष्यम्)

उभयतो नियमो विज्ञास्यते—क्षिज्योरेवैचः—इति, तयोश्च शक्यार्थ एव - इति ॥

(प्रदीपः) **उभयत इति** । योगविभागेनेति भावः ॥

(उद्योतः) **योगविभागेनेति** । विनिगमनाविरहात्क्षय्यभ्रूणे-त्यादाविवोभयतो नियम इत्यन्ये ॥

(इष्टानुपपत्तिभाष्यम्)

इहापि तर्हि नियमान्न प्राप्नोति—लव्यं - पव्यम्, अवश्यलाव्यम्-अवश्यपाव्यमिति ॥

(प्रदीपः) **इहापीति** । सामान्येन नियम इति प्रश्नः ॥

(इष्टानुपपत्तिभाष्यम्)

तुल्यजातीयस्य नियमः ॥

कश्च तुल्यजातीयः ?

यथाजातीयकः क्षिज्योरेच् ॥

कथंजातीयकः क्षिज्योरेच् ?

एकारः ॥

(प्रदीपः) **तुल्यजातीयस्येति** । कण्ठ्यतालव्यस्येत्यर्थः ॥

(उद्योतः) भाष्ये—**तुल्यजातीयस्येति** । अन्यथा यि प्रत्यय इति विधिवैयर्थ्यं स्यादिति भावः ॥ तत्त्वं च यत्वेन, तर्हि ऐकारे आयादेशः स्यादत आह—**कण्ठ्येति** । भाष्ये एकारग्रहण-मुपलक्षणमिति भावः ॥

(अनिष्टापत्तिभाष्यम्)

एवमपि रायमिच्छति-रैयतीत्यत्र प्राप्नोति ॥

(प्रदीपः) **रायमिच्छतीति** । एकारस्यैव नियमेन व्यावृत्तिः कृता, न त्वैकारस्येति प्रश्नः ॥

(उद्योतः) एतदनभिज्ञः शङ्कते—भाष्ये—**रायमिच्छतीति** ॥ तदाह—**एकारस्यैवेति** । एकारस्य तालव्यत्वमेवेति भाष्याशयः ॥

(अनिष्टापत्तिवारणभाष्यम्)

रा यि छान्दसः । दृष्टानुविधिश्छन्दसि भवति ॥

(प्रदीपः) **छान्दस इति** । क्यजन्तस्य रैशब्दस्य भाषायां नास्ति प्रयोगः, अन्यत्र तु विद्यत एवेति व्याचक्षते । [क्यच् त्वैकारान्तान्नास्ति, **"गोसमानाक्षरनान्तात्"** इति वचनात् ।] **अन्ये** तु भाषायां रैशब्दस्य प्रयोग एव नास्ती-त्याहुः ॥

(उद्योतः) **क्यजन्तेति** । राः—रैशब्दो यि—यकारादिप्रत्यये इति भाष्यार्थ इति भावः । भाष्ये विसर्गरहित एव पाठः ॥ एतेन रायिरित्ययुक्तं, आत्वस्य दुर्लभत्वात् । रैशब्दात्क्विप् दुर्लभ इत्यपा-स्तम् ॥ **नास्ति प्रयोग इति** । अनभिधानादिति भावः ॥ क्यच्-श्चित्यादिर्वचनादित्यन्तोऽग्रन्थः, तस्यैकीयमतत्वात् । अत एव **'नः क्ये'** इति सूत्रे वाच्यतीति भाष्ये प्रयुक्तम् ॥ **अन्ये त्विति** । अत्रा-रुचिबीजं तु **रायमिच्छतीति** भाष्यप्रयोगविरोधः । न हि विग्रहवच्छन्द इति बोध्यम् । भाष्ये यीत्यस्य वैयर्थ्याच्च ॥

(प्रथमान्तपाठे दूषणान्तरभाष्यम्)

"ऊदुपधाया गोहः" आदेशतोऽन्तरतमनिर्वृत्तौ सत्यामुपधाग्रहणं कर्तव्यम् ॥ प्रकृतितः पुनरन्तर-तमनिर्वृत्तौ सत्यामूकारस्य गोहो याऽन्तरतमा प्रकृतिस्तत्र षष्ठी, यत्र षष्ठी तत्रादेशा भवन्तीति अन्तरेणोपधाग्रहणं सिद्धं भवति ॥

(प्रदीपः) **गोह इति** । एतत्परिभाषोपस्थाने सति गोह इति षष्ठी अन्तरतमे स्थानिन्युपसंह्रियते ॥

(उद्योतः) भाष्ये—**गोहः** संबन्धिन ऊकारस्य याऽन्तरतमा प्रकृतिरित्यन्वयः ॥ **स्थानिन्युपसंह्रियत इति** । एवं च 'गोहः' इति गोह्वयवे लाक्षणिकम्—ऊकारान्तरतमस्य गोह्वयवस्योदित्यर्थ इति भावः ॥

(दूषणोद्धारभाष्यम्)

आदेशतोऽप्यन्तरतमनिर्वृत्तौ सत्यां न दोषः । क्रियते एतन्न्यास एव ॥

(प्रदीपः) **क्रियते न्यास एवेति** । अन्यथा परत्वाद-लोऽन्त्यस्येत्यनेन गोह इति षष्ठी अन्तेऽल्युपसंह्रियेतेति भावः ॥

(उद्योतः) ननूपधाग्रहणाकरणलाघवे दर्शिते **क्रियत इत्यु-**त्तरमसङ्गतमत आह—**अन्यथेति** । परत्वादलोऽन्त्यस्येत्येव व्य-वस्थापकं स्यादित्यर्थः ॥ एवं च पक्षद्वयेऽप्यावश्यकं तदिति भावः ॥

(प्रथमान्तपाठे दूषणान्तरभाष्यम्)

"रदाभ्यां निष्ठातो नः पूर्वस्य च दः" इति । आदेशतोऽन्तरतमनिर्वृत्तौ सत्यां तकारग्रहणं कर्त-व्यम् ॥ प्रकृतितः पुनरन्तरतमनिर्वृत्तौ सत्यां नका-रस्य निष्ठायां याऽन्तरतमा प्रकृतिस्तत्र षष्ठी, यत्र षष्ठी तत्रादेशा भवन्तीति अन्तरेणापि तकारग्रहणं सिद्धं भवति ॥

(प्रदीपः) **रदाभ्यामिति** । चरितमित्यादौ व्यवधानान्न भवति, **'निष्ठायाः'** इति पञ्चम्यास्तकार एवोपसंहारात्तस्यैवा-नन्तर्येण नत्वविधानात् ॥

(उद्योतः) ननु तग्रहणाभावे चरितमित्यादावपि रेफानन्तरा निष्ठेति नत्वं स्यादत आह—**चरितमिति** । रदाभ्यामित्यस्य प्रधानविशेषणताया न्याय्यतया परिभाषासंस्कृते लक्ष्यसंस्कारके वाक्ये रेफदकाराभ्यां परस्य निष्ठासंबन्धिनोऽन्तरतमस्य नकारादेश इत्यर्थ इति भावः ॥ **आदेः परस्य स्थानेऽन्तरतम** इत्याभ्यामादे-रन्तरतमस्य द इत्यर्थे एकारस्यान्तरतमत्वाभावेन तकारस्य चादित्वा-भावेनाप्राप्तिरिति **परे** ॥

(दूषणपरिहारभाष्यम्)

आदेशतोऽप्यन्तरतमनिर्वृत्तौ सत्यां न दोषः । क्रियत एतन्न्यास एव ॥

(प्रदीपः) **क्रियत एतन्न्यास एवेति** । अन्यथा भिन्नवद्भ्यामित्यत्र दकारस्य नत्वं स्यात् । स हि नकारस्य सुसदृशः, **यथा तृतीयास्तथा पञ्चमा** इति वचनात् ॥

न त्वकार इति तदादेशोऽप्यप्रत्यय इति भावः ॥

(उद्योतः) असित्ययमिति । प्रत्ययरूपविसर्गभिन्नस्येत्यर्थ इति भावः ॥

(आक्षेपबाधकभाष्यम्)

अप्रत्ययविसर्जनीयस्येत्युच्यते । प्रत्ययविसर्जनीयश्चायम् ॥

(प्रदीपः) **प्रत्ययेति** । प्रत्ययावयवत्वादकारोऽपि प्रत्ययः । अतस्तदादेशोऽपि प्रत्यय इति भावः ॥

(उद्योतः) अकारोऽपीति । अत्रत्यप्रत्ययशब्दस्तदवयवे लाक्षणिक इति भावः ॥

(आक्षेपसाधकभाष्यम्)

लुप्यतेऽत्र प्रत्ययः "रात्सस्य" इति ॥

(प्रदीपः) **लुप्यत इति** । सकारसन्निधिकालेऽकारेण नैव लब्धा प्रत्ययसंज्ञा, समुदायसन्निवेशिनीत्वात् तस्याः-इति कुतस्तदादेशस्तां लप्स्यते । उत्वे च कृतेऽवशिष्टः सकार एव प्रत्ययसंज्ञः स च लुप्त इति भावः ॥

(उद्योतः) **उत्वे च कृत इति** । न चैकादेशस्य परादिवत्त्वेन 'उस्' इत्यस्य प्रत्ययतया लोपे **एकदेशविकृतन्यायेन** 'उर्' इत्यस्य प्रत्ययतया विसर्गस्य प्रत्ययावयवत्वमस्त्येवेति वाच्यम् । त्रिपाद्या असिद्धत्वेन तत्रान्तादिवद्भावाप्रवृत्तेः । स्थानिवत्त्वेन तु न निर्वाहः, उपात्तस्य स्थानिनोऽकारस्य प्रत्ययत्वाभावात् । **सर्वे सर्वपदादेशा** इत्यनेन तु 'मातृ ङस्' इत्यस्य स्थानित्वेऽपि असित्यस्य स्थानित्वालाभात् ॥ भाष्ये **लुँप्यतेऽत्र प्रत्ययविसर्जनीय** इति पाठे योऽत्र प्रत्ययस्थानिकत्वेन तवाभिमतो विसर्जनीयः स लुप्यते-न दृश्यते, स्थानिनः प्रत्ययस्यैव लोपादित्यर्थः ॥

(समाधानवार्तिकशेषभाष्यम्)

एवं तर्हि—

(समाधाने भाष्यवार्तिकम्)

॥ भ्रातुष्पुत्रग्रहणं ज्ञापकमेकादेशनिमित्तात् षत्वप्रतिषेधस्य ॥

(भाष्यम्)

यदयं कस्कादिषु भ्रातुष्पुत्रशब्दं पठति, तज्ज्ञापयत्याचार्यः—नैकादेशनिमित्तात् षत्वं भवतीति ॥

(प्रदीपः) **एकादेशनिमित्तादिति** । एकादेशशास्त्रं निमित्तं यस्य तस्मात्परस्येत्यर्थः ॥

(उद्योतः) **एवं तर्हि भ्रातुष्पुत्रेति** । त्रिपाद्यामप्यन्तादिवद्भावप्रवृत्तिज्ञापनद्वारेति गूढोऽभिसन्धिः ॥ कर्मधारये निमित्तपदवैयर्थ्यमिति बहुव्रीहिम्, एकादेशपदे लक्षणां च दर्शयति—**एकादेशशास्त्रमिति** ॥

(पूर्वान्तत्वसाधनाधिकरणम्)

(आक्षेपभाष्यम्)

किं पुनरयं पूर्वान्तः, आहोस्वित्परादिः, आहोस्विदभक्तः?

(प्रत्याक्षेपभाष्यम्)

कथं वाऽयं पूर्वान्तः स्यात्? कथं वा परादिः? कथं वा अभक्तः?

(प्रत्याक्षेपसमाधानभाष्यम्)

यद्यन्त इति वर्तते, ततः पूर्वान्तः । अथादिरिति वर्तते, ततः परादिः । अथोभयं निवृत्तम्, ततोऽभक्तः ॥

(प्रदीपः) **यद्यन्त इति** । यद्यपि 'रपरः' इत्यत्रान्यपदार्थस्य प्राधान्यम्, तथापि रेफस्य विधेयतया प्राधान्यात्तस्यैवान्तत्वं विशेषणमिति भावः ॥ यद्यपि प्रसज्यमान एवाण् रपरो विधीयते, तथाप्यानन्त्यि साक्षादत्र 'अर्-आर्' इत्येवमविधानात्तात्पर्यपर्यालोचनन्यायेन केवलावस्थानात्पक्षत्रयविमर्शः ॥

(उद्योतः) **यद्यपीति** । तथा च तस्यैव विशेषणं स्यादिति भावः ॥ **प्राधान्यादिति** ॥ रपरशब्दतात्पर्यविषयत्वादित्यर्थः । एवं च पूर्वान्तावयवभूतरेफपरोऽणित्यर्थः ॥ सूत्रे **रपर** इति समासश्च सौत्रत्वात्साधुः ॥ [रः परो यस्येति बहुव्रीहिः । अवयवत्वमेव षष्ठ्यर्थः । वर्णस्य वर्णान्तरावयवत्वं तु गौणम् । यथा ह्रस्वस्य छे तुगित्यादाविति तात्पर्यम् ॥] नन्वरारादिरूपेण विधानात्कथमभक्तत्वादिशङ्केत्यत आह—**यद्यपीति** ॥ **अविधानादिति** । अनुच्चारणादित्यर्थः ॥ **तात्पर्येति** । प्राप्ताप्राप्तविवेकन्यायेनेत्यर्थः ॥ **केवलेति** । रेफमात्रविधौ सूत्रतात्पर्यादिति भावः ॥ यत्तु-अयमपि विचारो भूतस्याणो रपरत्वमिति पक्षे **नष्टाश्वरथन्यायेनानान्तर्यमेवान्तर्यमिति** ऋकारस्याकाराकारावेव गुणवृद्धी भविष्यतः । अरारादिरूपेण विधानमिति पक्षे तु आनङादौ नकारविषयो यथा न विचारस्तथाऽत्रापीति तत्त्वम्-इति ॥ तत्तु प्रकृतसूत्रे तस्य पक्षस्यास्थितत्वादयुक्तम् ॥

(भाष्यम्)

कश्चात्र विशेषः?

(२९८ अभक्तपक्षे दूषणवार्तिकम् ॥ १ ॥)

॥ * ॥ अभक्ते दीर्घलत्वयगभ्यस्तस्वरहलादिशेषविसर्जनीयप्रतिषेधः प्रत्ययाव्यवस्था च ॥ * ॥

(भाष्यम्)

यद्यभक्तः, दीर्घत्वं न प्राप्नोति—गीः, पूः । रेफवकारान्तस्य धातोरिति दीर्घत्वं न प्राप्नोति ॥

(उद्योतः) वार्तिके प्रतिषेधः—अभावो निवर्तनं च । आद्ये स्यादिति शेषः, द्वितीये वक्तव्यमिति ॥ गॄधोः क्विपि **गीः पूः** । **ऋत इत्**, उदोष्ठ्येतीत्वोत्वे ॥

(दूषणानुपपत्तिभाष्यम्)

किं पुनः कारणं रेफवकाराभ्यां धातुर्विशेष्यते, न पुनः पदं विशेष्येत—रेफवकारान्तस्य पदस्येति?

(उद्द्योतः) भाष्ये—पदमिति । पदस्येत्यनुवर्तमानमित्यर्थः ॥

(दूषणोपपत्तिभाष्यम्)

नैवं शक्यम् । इहापि प्रसज्येत—अग्निः, वायुरिति ॥

(दूषणानुपपत्तिभाष्यम्)

एवं तर्हि रेफवकाराभ्यां पदं विशेषयिष्यामः, धातुनेकम्—रेफवकारान्तस्य पदस्येको धातोरिति ॥

(दूषणोपपत्तिभाष्यम्)

एवमपि-प्रियं ग्रामणि कुलमस्य-प्रियग्रामणिः, प्रियसेनानिः-अत्रापि प्राप्नोति । तस्माद्धातुरेव विशेष्यते, धातौ च विशेष्यमाणे इह न प्राप्नोति-गीः, पूः ॥ दीर्घ ॥

(लत्वोदाहरणभाष्यम्)

लत्व । लत्वं च न सिध्यति—निजेगिल्यते । "ग्रो यङि" इति लत्वं न प्राप्नोति ॥

(प्रदीपः) लत्वं चेति । 'ग्रः' इत्यवयवषष्ठीति चोद्यम् ॥

(दोषबाधकभाष्यम्)

नैष दोषः । 'ग्रः' इत्यनन्तरयोगैषा षष्ठी ॥

(उद्द्योतः) अनन्तरयोगेति । अनन्तरशब्दोऽव्यवहितवाची ॥

(दोषसाधकभाष्यम्)

एवमपि स्वर्जेगिल्यत इत्यत्रापि प्राप्नोति ॥

(दोषबाधकभाष्यम्)

एवं तर्हि यङा आनन्तर्ये विशेषयिष्यामः ॥

अथवा 'ग्रः' इति पञ्चमी ॥ लत्व ॥

(यक्स्वरोदाहरणभाष्यम्)

यक्स्वर । यक्स्वरश्च न सिध्यति—गीर्यते स्वयमेव, पूर्यते स्वयमेव । "अचः कर्तृयकि" इत्येष स्वरो न प्राप्नोति, रेफेण व्यवहितत्वात् ॥

(दोषोद्धारभाष्यम्)

नैष दोषः । 'स्वरविधौ व्यञ्जनमविद्यमानवद्भवति' इति नास्ति व्यवधानम् ॥ यक्स्वर ॥

(उद्द्योतः) स्वरविधाविति । यद्यपि हल्स्वरप्राप्तौ स्वरोद्देश्यकविधौ चेदम् । अत एवाचः कर्तृ-इति सूत्रेऽच इति चरितार्थम् । तथापि तदनाश्रयेणैकदेशयुक्तिर्भाष्यमिति तत्त्वम् ॥

(अभ्यस्तस्वरोदाहरणभाष्यम्)

अभ्यस्तस्वर । अभ्यस्तस्वरश्च न सिध्यति—मा हि स्म ते पिपरुः, मा हि स्म ते बिभरुः । 'अभ्यस्तानामादिरुदात्तो भवतीति अजादौ लसार्वधातुके' इत्येष स्वरो न प्राप्नोति, रेफेण व्यवहितत्वात् ॥

(प्रदीपः) पिपरुरिति । पृ-लङ्-शप्-श्लुः-द्विर्वचनम् । अर्तिपिपर्त्योश्चेतीत्त्वम् । सिजभ्यस्तेति जुस् । जुसि चेति गुणः ॥

(उद्द्योतः) भाष्ये माङ्प्रयोगोऽडभावाय, तस्मिन् हि अट्स्वरः स्यात् । हिप्रयोगो हि चेति निघातनिषेधाय, स्मशब्दो लङ्सिद्धये ॥

(दोषोद्धारकभाष्यम्)

नैष दोषः । 'स्वरविधौ व्यञ्जनमविद्यमानवद्भवति' इति नास्ति व्यवधानम् ॥ अभ्यस्तस्वर ॥

(हलादिशेषोदाहरणभाष्यम्)

हलादिशेष । हलादिशेषश्च न सिध्यति—ववृते, ववृधे । अभ्यासस्येति हलादिशेषो न प्राप्नोति ॥ हलादिशेष ॥

(प्रदीपः) ववृत इति । अभ्यासावयवस्यानादेर्हलो निवृत्त्या भाव्यमिति रेफस्य निवृत्त्यसिद्धिः ॥

(उद्द्योतः) अभ्यासावयवस्येति । गर्भवदनवयवस्यापि तद्ग्रहणेन ग्रहणं सन्मध्यपतितन्यायेन । न त्वेतावताऽवयवत्वमिति भ्रमितव्यमिति भावः ॥ यद्वा 'ऋवर्णान्ताभ्यासस्य' इत्यर्थे पूर्वं तकारस्य हलादिशेषेण निवृत्तावुरदत्वम् । ततः पुनर्हलादिः शेषो न स्यात्, अनवयवत्वादिति भावः । न चैवं लक्ष्ये लक्षणस्येति न्यायेन पुनर्हलादिःशेषानापत्तिरिति वाच्यम् । लक्ष्यभेदात् ॥

(विसर्जनीयप्रतिषेधोदाहरणभाष्यम्)

विसर्जनीयः । विसर्जनीयस्य प्रतिषेधो वक्तव्यः—नार्कुटः, नार्पत्यः । "खरवसानयोर्विसर्जनीयः" इति विसर्जनीयः प्राप्नोति ॥ विसर्जनीय ॥

(प्रदीपः) नार्कुट इति । यस्मात्सुप्तिङ्विधिस्तदादि सुबन्तं तिङन्तं च—इति रेफान्तस्य पदत्वाद्विसर्जनीयप्रसङ्गः ॥

(उद्द्योतः) नृकुटीशब्दाद् भवादावण् । नृपतेर्दित्यदित्येति ण्यः ॥ ननु रेफान्तान्न सुब्विधिरिति कथं तदन्तस्य प्रत्ययलक्षणेन पदत्वमत आह—यस्मादिति । यस्माद्विधिस्तद्वृत्तिनृशब्दस्य नाशब्दस्य स्थानिवद्भावेन । तदादित्वं च रेफान्तस्य मुख्यम्, सुबन्तत्वं च प्रत्ययलक्षणेनेति भावः ॥

(प्रत्ययाव्यवस्थोदाहरणभाष्यम्)

प्रत्ययाव्यवस्था च । प्रत्यये व्यवस्था न प्रकल्प्येत—किरतः, गिरतः । रेफोऽप्यभक्तः, प्रत्ययोऽपि । तत्र व्यवस्था न प्रकल्पते ॥

(प्रदीपः) किरत इति । एकवचने किरतीति नित्यत्वात् पूर्वं विकरणः । आङ्गं तु कार्यमनित्यम् । अकृते हि विकरणे गुणः प्राप्नोति, कृते त्वित्त्वमिति । द्विवचने तु द्वयोरपि नित्यत्वात्परत्वादित्त्वम्, तत्र रेफोऽभक्तत्वान्न धात्ववयव इति विकरणो न स्यात् । स हि धातोः परो विधीयते । अथ विकरणात्परो रेफस्तदाऽप्यणः परो न स्यादिति व्यवस्था द्वयोर्न प्रकल्पते । अथ व्यवहितेऽपि परशब्दस्य प्रवृत्तिस्तथापि समीहिता व्यवस्था न प्रकल्पत इति प्रत्ययाव्यवस्थोक्ता ॥

(उद्द्योतः) एकवचनान्तानुदाहरणे बीजमाह—एकेति ॥ नित्यत्वादिति । विकरणविधौ 'सार्वधातुके' इति विषयसप्तमी । अन्यथाऽभक्तत्वेऽनन्तरसार्वधातुकाभावेन विकरणाप्राप्तेर्नित्यत्वं व्याहतं

स्यादिति भावः ॥ नित्यत्वादिति । तसो ङित्त्वादित्वस्यैव प्रवृत्तेः ॥ न प्रकल्पेत इति । नियमेन विकरणस्यैव व्यवहितपरत्वं न सिध्येदिति भावः ॥

(पूर्वान्तपक्षाभ्युपगमभाष्यम्)

एवं तर्हि पूर्वान्तः करिष्यते ।

(२९९ पूर्वान्तपक्षे दूषणाक्षेपवार्तिकम् ॥ २ ॥)

॥ * ॥ पूर्वान्ते वैवधारणं विसर्जनीयप्रतिषेधो यकृस्वरश्च ॥ * ॥

(भाष्यम्)

यदि पूर्वान्तः, रोरवधारणं कर्तव्यम्—"रोः सुपि" रोरेव सुपि नान्यस्य । सर्पिष्षु, धनुष्षु । इह मा भूत्—गीर्षु, पूर्षु ॥

(प्रदीपः) गीर्ष्विति । परादौ सुब्ग्रहणेन गृह्यत इति न पदान्तत्वमिति भावः ॥ अभक्तपक्षेऽपि तदादिवचनात्प्राप्तिरिति कर्तव्यं वैवधारणम् ॥

(इतरपक्षेऽपि लाघवाभावभाष्यम्)

परादावपि सत्यवधारणं कर्तव्यम्—चतुर्ष्वित्येवमर्थम् ॥

(विसर्जनीयप्रतिषेधोदाहरणभाष्यम्)

'विसर्जनीयप्रतिषेधः' । विसर्जनीयस्य च प्रतिषेधो वक्तव्यः–नार्कुटः, नार्पत्यः । खरवसानयोर्विसर्जनीयः प्राप्नोति ॥

(इतरपक्षेऽपि लाघवाभावभाष्यम्)

परादावपि विसर्जनीयस्य प्रतिषेधो वक्तव्यः, नार्कल्पिरित्येवमर्थम् । कल्पिपदसंघातभक्तोऽसौ नोत्सहतेऽवयवस्य पदान्ततां विहन्तुमिति विसर्जनीयः प्राप्नोति ॥

(प्रदीपः) कल्पिपदेति । नृकल्पशब्दादिञि वृद्धौ च रेफः प्रत्ययसमुदायस्य कल्पिशब्दस्य भक्तत्वादवयवः, न तु कल्पशब्दस्य । ततश्च कल्पशब्दे परतः पदसंज्ञा विधीयमाना तदादीत्यधिकारात् रेफान्तस्य भवतीति विसर्जनीयप्रसङ्गः । पदशब्देन पद्यतेऽनेनार्थ इति-प्रत्यय उच्यते । तेन प्रत्ययसमुदायभक्तो रेफः कल्पशब्दे परतो व्यवस्थितो न कल्पावयव इति तयोः पौर्वापर्यमस्त्येवेत्यवयवस्यात्मन एव पदान्ततां विहन्तुं नोत्सहत इत्यर्थः । कचित्तु कल्पपदसंघात इति पाठः । तत्रायमर्थः—कल्पशब्दस्य संबन्धि यत्पदं नार्कल्पिरिति तस्य पदस्य योऽवयवः प्रत्ययसंघातः कल्पिशब्दस्तद्भक्त इत्यर्थः ॥

(उद्योतः) नृकल्पेति । नृशब्दात्कल्पः प्रत्ययः ॥ पदसंज्ञेति । स्वादिष्वित्यनेन । यद्यसौ कल्पशब्दावयवः स्यात् तदा स्वावयवभूतरेफान्तस्य 'नार्' इत्यस्य न स प्रत्ययः परः स्यादिति भावः ॥ परादिरित्यत्र परशब्देन परत्वपर्याप्त्यधिकरणो यावान् स सर्वोऽपि गृह्यते, न तदवयवोऽपीति तात्पर्यम् ॥ ननु प्रत्ययस्य कथं पदत्वमत आह—पदशब्देनेति । कल्पिरूपः पदसङ्घातः पदसमुदाय इति भाष्यार्थः । तस्मात्पक्षत्रयेऽपि विसर्जनीयप्रतिषेधस्य वक्तव्यतया नायं दोष इति भावः ॥ पूर्वैर्बहिरङ्गासिद्धत्वं तु नोक्तम्, त्रिपादीस्थेऽन्तरङ्गे तत्परिभाषाया अप्रवृत्तेः ॥

(यकृस्वरोदाहरणभाष्यम्)

'यकृस्वरश्च' । यकृस्वरश्च न सिध्यति—गीर्यते स्वयमेव, पूर्यते स्वयमेव । "अचः कर्तृयकि" इत्येष स्वरो न प्राप्नोति ॥

(दूषणबाधकभाष्यम्)

नैष दोषः । उपदेश इति वर्तते ॥

(उद्योतः) भाष्ये—उपदेश इति वर्तत इति । अचः कर्त्रित्यत्र तास्यनुदात्तेदित्यत इत्यर्थः ॥

(परादिपक्षाभ्युपगमभाष्यम्)

अथवा पुनरस्तु परादिः ॥

(३०० परादिपक्षे दूषणाक्षेपवार्तिकम् ॥ ३ ॥)

॥ * ॥ परादावकारलोपौत्वपुक्प्रतिषेधश्चङ्युपधाह्रस्वत्वमिटो व्यवस्थाऽभ्यासलोपोऽभ्यस्ततादिस्वरो दीर्घत्वं च ॥ * ॥

(भाष्यम्)

यदि परादिः, अकारलोपः प्रतिषेध्यः-कर्ता, हर्ता । "अतो लोपः" 'आर्द्धधातुके' इत्यकारलोपः प्राप्नोति ॥

(उद्योतः) भाष्ये—अथवा पुनरस्तु परादिरिति । वैवधारणविसर्जनीयप्रतिषेधयोः कर्तव्यतायाः पूर्वान्तपरादिपक्षयोः समत्वात् परादिपक्षो वा वक्तव्यः पूर्वान्तो वेत्यत्र न विशेष इति चेत् कश्चिद् ब्रूयात् तत्राह वार्तिककारः—परादावितीत्यर्थः ॥ परादाविति । वार्तिके पुगन्तद्वन्द्वस्य प्रतिषेधपदेन षष्ठीतत्पुरुषः । वक्तव्य इति शेषः । चङ्युपधाह्रस्वत्वं वक्तव्यम् । अग्रे सर्वत्रायमेव शेषो बोध्यः ॥

(दूषणबाधकभाष्यम्)

नैष दोषः । उपदेश इति वर्तते ॥

(उद्योतः) उपदेश इति वर्तत इति । अतो लोप इत्यत्रानुदात्तोपदेश इत्यत इत्यर्थः ॥

(दूषणसाधकभाष्यम्)

यद्युपदेश इति वर्तते, 'धिनुतः, कृणुतः' अत्र न प्राप्नोति ॥

(प्रदीपः) धिनुत इति । एकवचनेऽसत्यप्यकारलोपे आद्गुणेन वा, विकरणस्य वा गुणे पररूपेण धिनोतीति सिध्यतीति द्विवचनमुदाहृतम् ॥

(उद्द्योतः) पररूपेण—अतो गुण इत्यनेन ॥

(दूषणबाधकभाष्यम्)

नोपदेशग्रहणेन प्रकृतिरभिसंबध्यते ॥
किं तर्हि ?
आर्धधातुकमभिसंबध्यते—आर्धधातुकोपदेशे यदकारान्तमिति ॥ अकारलोप ॥

(प्रदीपः) आर्धधातुकोपदेश इति । संनियोगेन चाकारस्य विधानादार्धधातुकप्रतिपत्तिकालेऽकारान्तप्रतिपत्त्या सिद्धो लोपः ॥

(औत्वोदाहरणभाष्यम्)

औत्व । औत्वं च प्रतिषेध्यम् । चकार, जहार । "आत औ णलः" इत्यौत्वं प्राप्नोति ॥

(दोषोद्धारभाष्यम्)

नैष दोषः । 'निर्दिश्यमानस्यादेशा भवन्ति' इत्येवं न भविष्यति ॥

(प्रदीपः) निर्दिश्यमानस्येति । नन्वादेः परस्येति रेफस्यौत्वेन भाव्यम् ॥ नैष दोषः । णल इत्यनेन यत्प्रत्यायितं प्रयोगविषयमकारमात्रं तस्याकारान्तादङ्गादुत्तरस्यादेशः प्रवर्तते, सरेफस्य त्वनुमीयमानत्वादादेशाभावः । प्रत्याय्यप्रत्यायकाभेद-विवक्षया षष्ठीनिर्दिष्टस्यादेशा इत्युच्यते ॥

(उद्द्योतः) नन्विति । आदेः परस्येति निर्दिश्यमान-परिभाषाबाधकमित्यभिमानः ॥ तस्यैवायमनुसंहार इत्युत्तरम् ॥ ननु सूत्रे उच्चारितस्य णलो नादेशः, किंतु तत्प्रत्यायिताकारस्येति 'षष्ठीनिर्दिष्टस्यादेशाः' इत्ययुक्तं स्यादत आह—प्रत्याय्येति । निर्दिश्यमानस्येत्यस्य प्रतिपादितस्येत्यर्थे तु पादन्तस्यापि पदादेशा-पत्तिरिति बोध्यम् ॥

(आक्षेपभाष्यम्)

यस्तर्हि निर्दिश्यते तस्य कस्मान्न भवति ?

(समाधानभाष्यम्)

रेफेण व्यवहितत्वात् ॥ औत्व ॥

(प्रदीपः) रेफेणेति । यद्रूपं षष्ठीनिर्दिष्टमकारमात्रं तद्व्य-वहितमित्यर्थः । यदि तु प्रत्ययस्येत्युच्यते लिट, इति च तदा व्यवधानाभावात् स्यादेवादेशः ॥

(उद्द्योतः) यदि स्विति । तथा तु वक्तुमशक्यं, सर्वत्रादेशा-पत्तेरिति भावः ॥

(उदाहरणभाष्यम्)

पुक्प्रतिषेध । पुक् च प्रतिषेध्यः-कारयति, हारयति । 'आतां पुक्' इति पुक् प्राप्नोति ॥

(उदाहरणभाष्यम्)

चङ्युपधाह्रस्वत्वम् । चङ्युपधाह्रस्वत्वं च न सिध्यति—अचीकरत्, अजीहरत् । "णौ चङ्युप-धाया ह्रस्वः" इति ह्रस्वत्वं न प्राप्नोति ॥

(उदाहरणभाष्यम्)

इटो व्यवस्था । इटश्च व्यवस्था न कल्पते—आस्त-रिता, निपरिता । इडपि परादिः, रेफोऽपि । तत्र व्यवस्था न प्रकल्पते ॥ इटो व्यवस्था ॥

(प्रदीपः) आस्तरितेति । नित्यत्वाद् गुणे रपरत्वे च कृते नेड्वशि कृतीति प्रतिषेधादप्रवृत्तिलक्षणेटोऽव्यवस्था । प्रवृत्तौ वा रेफात् पूर्वं इडित्यनिष्टा व्यवस्था प्राप्नोति ॥

(उद्द्योतः) कथं तर्हीडपीत्यादिभाष्यमत आह—प्रवृत्तौ वेति । नेड्वशीत्यत्र 'उपदेशे' इत्यपकृष्योपदेशे वशादेरेव निषेध इति भावः ॥

(उदाहरणभाष्यम्)

अभ्यासलोपः । अभ्यासलोपश्च वक्तव्यः—वव्रृते, वव्रृधे । 'अभ्यासस्य' इति हलादिःशेषो न प्राप्नोति ॥ अभ्यासलोप ॥

(उद्द्योतः) भाष्ये—वव्रृत इति । ऋवर्णान्ताभ्यासस्यादि-त्यर्थे पूर्वं तलोपे पश्चाद्रेफस्तस्य लोप इति पक्षे इदम् ॥ 'वैत्रे' इत्यप्युदाहार्यम् ॥

(उदाहरणभाष्यम्)

अभ्यस्तस्वर । अभ्यस्तस्वरश्च न सिध्यति—मा हि स्म ते पिपरुः, मा हि स्म ते बिभरुः । 'अभ्यस्ता-नामादिरुदात्तो भवतीति अजादौ लसार्वधातुके' इत्येष स्वरो न प्राप्नोति ॥ अभ्यस्तस्वर ॥

(उदाहरणभाष्यम्)

तादिस्वर । तादिस्वरश्च न सिध्यति—प्रकर्ता, प्रकर्तुम् । "तादौ च निति कृत्यतौ" (६।२।५०) इत्येष स्वरो न प्राप्नोति ॥

(उद्द्योतः) प्रकर्तेति । तृन् ॥ एषस्वरः—पूर्वपदप्रकृति-स्वरः ॥

(दूषणबाधकभाष्यम्)

नैष दोषः । उक्तमेतत्—*कृदुपदेशे वा ताद्यर्थ-मिडर्थम् * इति ॥

(उद्द्योतः) कृदुपदेशकालिकतादिप्रत्ययप्रतीत्यर्थं तादाविति सूत्रे कृद्ग्रहणमिति भाष्योदाहृतवार्तिकार्थः । तादावितिसूत्रेण गतेः स्वरो विधीयते । क्रियायोगे च गतित्वम् । क्रियावाची च धातुः । तत्र तिङन्ते पूर्वपदाभावेन कृदन्त एव सिद्धमिति कृद्ग्रहणमुक्तार्थम् । न च कृद्ग्रहणाभावे तादिस्वमुत्तरपदस्य विशेषणं स्यात्, तथा च 'प्रतरिता' इत्यादावेव स्यादिति तस्य कृद्विशेषणत्वाय तदिति वाच्यम् । छौतेनित्प्रत्ययविशेषणतायां एव न्याय्यत्वादिति दिक् ॥

(उदाहरणभाष्यम्)

'दीर्घत्वं च' न सिध्यति । गीः, पूः । 'रेफवकारा-न्तस्य धातोः' इति दीर्घत्वं न प्राप्नोति ॥ उरण् रपरः ॥ ५१ ॥

(प्रदीपः) गीरिति । अन्तरङ्गत्वाद्विलोपे कृते इत्वे रप-रत्वे च सुपोऽयमादौ रेफ इति कल्पनायां राल्लस्येति सुलोपे कृते दीर्घत्वं न स्यादिति पूर्वान्तपक्षोऽत्र स्थितः ॥ ५१ ॥

(उद्द्योतः) ननु रेफस्य परादित्वेऽपृक्तस्याभावाद्विलोपो न

प्राप्नोतीति कुतो नोक्तम्? अत आह—अन्तरङ्गत्वादिति ॥ तदानीं सुपोऽभावादाह—कल्पनायामिति । पदस्य विभज्यान्वाख्यानमिति भावः ॥ पूर्वान्तेति । नार्कुट्यादौ वचनेनैव निर्वाह इति भाष्ये उक्त इति बोध्यम् ॥ एवं च रपर इति अवयववाचिपरशब्देन षष्ठ्यर्थे बहुव्रीहिरिति ध्वनितम् । अवयवत्वं चावयवसादृश्ये पर्यवस्यति । न हि वर्णस्य वर्णान्तरमवयवो भवति । अत एव प्रसक्तावस्थायां रपरत्वेऽपि गुणादिशब्देन विधानम्, यदागमा इति न्यायेन विशिष्टस्य गुणादित्वात् । एवं ऋवर्णादचि पूर्वपरयोरन्तरतमो रपरोऽण् भवतीत्यर्थ इति बोध्यम् ॥ गुणादिशब्देनारारोर्ग्रहणाभावे तु 'ऋकारस्य गुणवृद्धी अरारावेव' इति नियमो न स्यात्, यतो गुणादिशब्देन अकारादे रेफः परो यस्मात्तादृशस्य विधानम् । गुणत्वादिकं चाकारादिनिष्ठमेव । तेन च नान्तर्यम् । एतदेवाभिप्रेत्य रदाभ्यामिति सूत्रे भाष्ये गुणो भवति वृद्धिर्भवतीति रेफशिरा गुणवृद्धिसंज्ञकोऽभिनिर्वर्तत इति वक्ष्यति ॥ अत एव 'यद्यन्त इति वर्तते ततः पूर्वान्तः' इत्युपक्रमस्थं भाष्यमेकदेश्युक्तिः । तथा हि सति यथा परादिपक्षे नार्कुटिपरित्यादौ रेफस्य कल्पीति समुदायावयवत्वोपपत्तये परत्वपर्याद्यधिकरणादिरित्यर्थस्तथा पूर्वान्त इत्यस्य पूर्वत्वपर्याप्त्यधिकरणान्त इत्यर्थापत्तौ उक्तदोषो रदाभ्यामिति सूत्रस्थभाष्यविरोधश्चेत्याहुः ॥ ५१ ॥

(४७ परिभाषासूत्रम् ॥ १ । १ । ७ आ. ८)

अलोऽन्त्यस्य ॥ १ । १ । ५२ ॥

(अल्ग्रहणविशेषणताविचारः)

(आक्षेपभाष्यम्)

किमिदमल्ग्रहणं—अन्त्यविशेषणम्, आहोस्वित्—आदेशविशेषणम्?

(प्रदीपः) **अलोऽन्त्यस्य ॥ ५२ ॥ किमिदमिति ।** षष्ठीप्रथमयोर्निर्देशस्य साम्यात् **प्रश्नः** ॥

(भाष्यम्)

किं चातः?

(अन्त्यविशेषणत्वे दूषणभाष्यम्)

यद्यन्त्यविशेषणम्, आदेशोऽविशेषितो भवति ॥

तत्र को दोषः?

अनेकालप्यादेशोऽन्त्यस्य प्रसज्येत ॥

(उद्द्योतः) अलोन्त्य० ॥ ५२ ॥ भाष्ये—प्रसज्येतेत्यनन्तरं तन्निवृत्तयेऽनेकाल् सर्वस्येति वाच्यं स्यादिति शेषः ॥

(आदेशविशेषणपक्षे लाघवभाष्यम्)

यदि पुनः "अलन्त्यस्य" इत्युच्येत, तत्रायमप्यर्थः—"अनेकाल्शित्सर्वस्य" इत्येतन्न वक्तव्यं भवति । इदं नियमार्थं भविष्यति—अलेवान्त्यस्य भवति, नान्य इति ॥

(प्रदीपः) **यदि पुनरिति** । प्रथमाबहुवचनम्—अल इति यदि व्याख्यायेतेत्यर्थः । अस्मिंश्च पक्षे—**रहोरजसां लोपश्चेति** लोपः सर्वादेशः प्राप्नोति–विरजीकरोतीति ॥ **इदं नियमार्थमिति** । अन्त्यस्यादेशा भवन्तीत्यलोऽप्याक्षेपादल्ग्रहणमनल्व्यावृत्त्यर्थमिति भावः ॥

(**उद्द्योतः**) नन्वलन्त्यस्येत्युच्यमाने सूत्रभेदः स्यादत आह—**प्रथमेति** । बहुत्वस्याविवक्षितत्वं दर्शयितुमेवमुक्तमिति भावः ॥ **प्राप्नोतीति** । लोपस्याभावरूपत्वेनाल्रूपत्वाभावादिति भावः । एवं चायं पक्षो दुष्ट एव ॥ **क्सस्याचीति** लोपे प्रकृते **लुग्वा दुहेति** लुग्ग्रहणस्य—प्रथमान्तपक्षेऽल्ग्रहणमनेकाल्भिन्नलक्षकमित्यर्थज्ञापकत्वमिति नायं दोष इति भाष्याशयमन्ये ॥ भाष्ये— **इदं नियमार्थमिति**–इदमा सूत्रं तु न परामृश्यते, अप्राप्तान्त्यादेशविध्यर्थत्वस्य । किंतु अलपदं - इति तस्य नियमार्थत्वमुपपादयति—**अन्त्यति** ॥ **अलोऽपीति** । अलात्मकादेशस्यापीत्यर्थः ॥ **अपिना**–अनेलोऽपि ॥

(आदेशविशेषणत्वपक्षे आक्षेपभाष्यम्)

एवमप्यन्त्योऽविशेषितो भवति ॥

तत्र को दोषः?

वाक्यस्यापि पदस्याप्यन्त्यस्य प्रसज्येत ॥

(प्रदीपः) **वाक्यस्याऽपीति** । दोषपरत्वादेवमुक्तम्, न तु वाक्यं षष्ठीनिर्दिष्टमस्ति ॥ पदस्य तु परमानडुद्भ्यामित्यत्रानडुच्छब्दस्यान्त्यस्य सर्वस्य दत्वं प्राप्नोति ॥

(उद्द्योतः) **न त्विति** । 'षष्ठी स्थाने' इत्यनुवर्त्य स्थानषष्ठीबोधितान्त्यस्येति व्याख्यानादित्यर्थः ॥ यत्तु **यथातथायथापुरयोरिति** सूत्रे **न यथातथा–अयथातथा, अयथातथाभावोऽयाथातथ्यमिति** भाष्यदर्शनात्तत्प्रामाण्येन निपातसमुदायात् प्रत्ययः, निपातसमुदायेन नञ्समास इत्यङ्गीकार्यम् । तत्रायथातथाशब्दात् ष्यञि **यस्येति** लोपोऽवर्णान्ताङ्गस्य भसंज्ञकस्य जायमानस्तदन्त्यस्य यथातयेति पदसमुदायस्य स्यादिति ॥ तत्र, **निर्दिश्यमान**परिभाषया सिद्धेः । तदनाश्रयेण वा तदुक्तिः ॥ **पदस्य त्विति** । अधिकृतपदस्येत्यस्य वस्त्रादिभिर्विशेषणादित्यर्थः ॥

(अन्त्यविशेषणत्वेऽपि गौरवनिरासभाष्यम्)

यदि खल्वप्येषोऽभिप्रायः–तन्न क्रियेतेति, अन्त्यविशेषणेऽपि सति तन्न करिष्यते ॥

कथम्?

ङिच्चालोऽन्त्यस्येत्येतन्नियमार्थं भविष्यति—ङिदेवानेकालन्त्यस्य भवति नान्य इति ॥

(प्रदीपः) **यदि खल्वपीति** । अवश्यकर्तव्योऽसौ योगोऽपवादविप्रतिषेधार्थः ॥ अथ लाघवमात्रे आदरस्तत्राप्युच्यते-अन्त्यविशेषणेऽपीति ॥

(उद्द्योतः) **'यदि खलु'** इति पराभिप्रायं वदता सूचितमन्यादृशं स्वाभिप्रायं प्रकटयति–**अवश्येति** ॥ **असौ योगः–'अनेकाल्शित्'** इति योगः । **अतो भिस** इत्यादावादेः **परस्ये**त्यादिबाधनार्थं इति

भावः ॥ नन्वस्यावश्यकत्वेऽन्त्यविशेषणेऽपीत्यादिग्रन्थोऽसङ्गतोऽत आह—अथेति । अलिति प्रथमान्तं मण्डूकानुवृत्त्याऽऽदेः परस्येत्यत्र संबध्यत इति ऐसादौ न दोषः । तातङ्यपि ज्ञापकात्सर्वादेशत्वं भविष्यतीति भावः ॥ भाष्ये—छिद्वेवानेकालन्त्येति । अल्रूपत्वस्य फलाभावादनेकालिति लभ्यम् ॥ एवं चास्य सत्रस्यानेकालादेशेऽप्रवृत्त्यैतत्साहचर्यादादेः परस्येत्यस्याप्यनेकाल्यादेशेऽप्रवृत्तिरिति दिक् ॥

(स्थानषष्ठीविषयत्वस्थापनम्)

(आक्षेपभाष्यम्)

किमर्थं पुनरिदमुच्यते?

(उद्द्योतः) किमर्थं पुनरिति । किं स्थानषष्ठीनिर्देशविषयम्, उत षष्ठीमात्रविषयमिति प्रश्नः ॥

(३०१ समाधानवार्तिकप्रथमखण्डम् ॥ १ ॥)

॥ * ॥ अलोऽन्त्यस्येति स्थाने विज्ञातस्यानुसंहारः ॥ * ॥

(भाष्यम्)

अलोऽन्त्यस्येत्युच्यते स्थाने विज्ञातस्यानुसंहारः क्रियते । स्थाने प्रसक्तस्य ॥

(प्रदीपः) स्थाने विज्ञातस्येति । 'षष्ठी स्थानेयोगा' इत्यनुवर्तते । तेन या षष्ठी स्थानेयोगत्वेन विज्ञाता साऽन्त्यमलमनुसंह्रियते । आदेशो वा यो निश्चितः सोऽन्त्यस्यालः स्थाने-इत्यनुसंह्रियते ॥

(उद्द्योतः) स्थाने विज्ञातस्य कस्येत्यपेक्षायामाह—षष्ठीति । स्थाननिरूपितसंबन्धार्थकत्वेन ज्ञातस्य षष्ठीरूपप्रत्ययस्येत्यर्थः ॥ नन्वेवं 'विज्ञातायाः' इति वक्तुं युक्तमत आह—आदेशो इति । स्थानषष्ठीसंबन्धादादेशत्वेन यो विज्ञात इत्यर्थः ॥ अन्ये तु—अलोऽन्त्यस्येति यदुच्यते तेन स्थाने विज्ञातस्य—समुदायस्थाने प्रसक्तस्यान्त्येऽल्यनुसंहारः—उपसंहारः-तत्स्थानिकत्वमात्रं क्रियते—बोध्यत इति भाष्याक्षरार्थः ॥ स्थाने विज्ञातस्येत्यस्य व्याख्या—स्थाने प्रसक्तस्येति । कैयटव्याख्याने एतदैयर्थ्यं भावीत्याहुः ॥

(३०२ समाधानसाधकवार्तिकद्वितीयखण्डम् ॥ २ ॥)

॥ * ॥ इतरथा ह्यनिष्टप्रसङ्गः ॥ * ॥

(भाष्यम्)

इतरथा ह्यनिष्टं प्रसज्येत । टित्किन्मितोऽप्यन्त्यस्य स्युः ॥

(प्रदीपः) इतरथेति । यदि षष्ठीमात्रमनुसंह्रियेतेत्यर्थः । अत्र 'लविता' इति तृच ऋकारात्पूर्वमिदं प्राप्नोतीति दोषः । 'दापयति' इति पुगाकारस्य स्यात् । ततो यथुक्तमर्थवतो ह्यागम इति, तन्न युज्यते ॥

(उद्द्योतः) षष्ठीमात्रमिति । उपलक्षणमेतत्, षष्ठीमात्रोच्चारणेन विधीयमानं वेत्यपि बोध्यम् ॥ ततो यथुक्तमिति । आकारावयवत्वे 'प्रणिदापयति' इत्यादौ णत्वं न स्यादित्यर्थः ॥ न चावयवावयवः समुदायावयव इति निर्वाहः, यैस्यावयवस्तद्विशिष्टे यत्र तदवयवधृत्तिधर्मबुद्धिस्तात्कृशस्यावयवावयवस्य समुदायावयवत्वबुद्धिर्हि लोकसिद्धा, यथा भुजावयवाङ्गुल्यादिविशिष्टे भुजत्वबुद्धिसत्त्वात्तदवयवकशरीरावयवत्वबुद्धिरङ्गुल्यादौ । न चैवमत्राकारावयवपकारादिविशिष्टेऽवर्णत्वादिबुद्धिः । अर्थवत आगमे तु तद्विशिष्टे तदर्थवत्त्वबुद्ध्या तद्बुद्धिसत्त्वेन भवत्येव समुदायावयवत्वमिति 'भविता' इत्यादावङ्गावयवत्वं सम्भवतीति-इटो गुणनिषेधचारितार्थ्यमपि । वर्णस्य वर्णावयवत्वं तु वाचनिकं गौणम् । तत्र यावद्वचनं वाचनिकमिति न्यायेन समुदायावयवत्वे मानाभाव इत्याशयः ॥

(दूषणाप्राप्तिसंभावनाभाष्यम्)

यदि पुनरयं योगशेषो विज्ञायेत ॥

(प्रदीपः) यदि पुनरिति । 'षष्ठी स्थानेयोगा' इत्यनेनास्यैकवाक्यता । अत्र तु प्रदेशे करणं ङिच्चेत्यादेः सम्बन्धार्थम् । तत्रायमर्थो भवति—शास्त्रे या षष्ठी साऽन्त्येऽलि, सा च स्थानेयोगैवेति । न तु स्थाने विज्ञातस्य पश्चादनुसंहारः, प्रतिपत्तिगौरवप्रसङ्गादिति भावः ॥

(उद्द्योतः) संबन्धार्थमिति । अन्त्यस्येत्यनेनेति भावः । शास्त्रे येति । या षष्ठी सा स्थानेयोगैव सा चान्त्येऽलीति तु नार्थः, स्थानेयोगेति पदावृत्त्यापत्तेः । इदमेव प्रतिपत्तिगौरवम् । तस्माच्छास्त्रे या षष्ठी सा स्थानेयोगैवान्त्येऽल्येव चेति वाक्यार्थ इति भावः ॥ सा चेति । सा षष्ठी स्थानेयोगैव चेत्यन्वयः ॥

(समाधानसाधकभाष्यवार्तिकम्)

॥ योगशेषे च ॥

(भाष्यम्)

किम्?

अनिष्टं प्रसज्येत—टित्किन्मितोऽप्यन्त्यस्य स्युः । तस्मात्सूच्यते-* अलोऽन्त्यस्येति स्थाने विज्ञातस्यानुसंहारः *इतरथा ह्यनिष्टप्रसङ्ग* इति ॥ अलोऽन्त्यस्य ॥ ५२ ॥

(प्रदीपः) अनिष्टमिति । 'आद्यन्तौ टकितौ, मिदचोऽन्त्यात्परः' इत्येताभ्यां स्थानेयोगत्वमेव बाध्यते, तुल्यजातीयत्वात्सम्बन्धस्य सम्बन्धान्तरेण बाधोपपत्त्या । षष्ठ्यास्तु यद्रूपं तदन्त्य एवाल्यवस्थितमिति पूर्ववद्दोषप्रसङ्गः ॥ अनुसंहारः पुनरनुसंहारान्तरेण 'आदेः परस्यानेकाल् शित्सर्वस्य' इत्यनेन बाध्यते ॥ ५२ ॥

(उद्द्योतः) स्थानेयोगत्वमेव बाध्यत इति । अत्र हेतुः—तुल्येत्यादिरुपपत्त्येत्यन्तः ॥ संबन्धस्येत्यादि । संबन्धनिरूपकस्य संबन्धनिरूपकान्तरेणेत्यर्थः । सन्नियोगशिष्टन्यायस्तु न परिभाषाविषये, सन्निहितत्वादेरुत्तराङ्गविकलत्वायास्तत्र तत्रोपस्थितिस्वीकारादित्याशयः ॥ त्वनेन बाध्यत इति । न त्वाद्यन्तौ टकितावित्यनेनेति भावः ॥ ५२ ॥

(४८ परिभाषासूत्रम् ॥ १ । १ । ७ आ. ९)

ङिच्च ॥ १ । १ । ५३ ॥

(तातङि सर्वादेशत्वसाधनाधिकरणम्)

(आक्षेपभाष्यम्)

तातङ् अन्त्यस्य स्थाने कस्मान्न भवति? 'ङिच्चा-लोऽन्त्यस्य' इति प्राप्नोति ॥

(उद्योतः) ङिच्च ॥ ५३ ॥ भाष्ये—कस्मान्न भवतीति । येन नाप्राप्तिन्यायेनास्यानेकालित्यपवादत्वादिति भावः ॥ उत्तरस्य त्वयं भावः—नेदमपूर्वविधायकम्, किंतु तत्र तत्र ङित्करणसामर्थ्यसिद्धानेकालित्येतद्बाधानुवादकम् । अनुवादफलं तु ङित्त्वसामर्थ्यादर्थान्तरकल्पनानिवृत्तिः । ऐवं च प्रकृते नास्य प्रवृत्तिः । प्रवृत्तौ हि शास्त्रस्यापूर्वविधायकतापत्त्या गौरवापत्तिः । [1]एवं च यत्र सर्वादेशे ङित्वस्य वैयर्थ्यं तत्र तद्बाधः । यत्र तु न, तत्र न तद्बाध इति भावः ॥

(३०२ समाधानवार्तिकम् ॥ १ ॥)

॥ * ॥ तातङि ङित्करणस्य सावकाशत्वाद्विप्रतिषेधात्सर्वादेशः ॥ * ॥

(भाष्यम्)

तातङि ङित्करणं सावकाशम् ॥

कोऽवकाशः?

गुणवृद्धिप्रतिषेधार्थो ङकारः । तातङि ङित्करणस्य सावकाशत्वाद्विप्रतिषेधात्सर्वादेशो भविष्यति ॥

(प्रदीपः) ङिच्च ॥ ५३ ॥ **विप्रतिषेधादिति** । नन्वयमपवादः, 'अनेकाल् शित्-' इत्युत्सर्गः । उत्सर्गापवादयोश्चायुक्तो विप्रतिषेधः । नैतदस्ति । ङित्त्वस्यान्यार्थत्वसंभवे सति दौर्बल्यात् सन्दिग्धोपस्थानोऽयं योग इत्यपवादत्वमेवात्र विषयेऽस्य नास्ति ॥

(उद्योतः) (भाष्ये) **विप्रतिषेधादिति** । पैरिभाषात्वविरोधादित्यर्थः । यदि सावकाशङित्त्वेऽपि प्रवृत्तिः स्यात्तदाऽनुवादत्वासंभवेन परिभाषाप्रकरणविरोध इति भावः ॥ यथा चैतत्तथाऽनुपदमेव स्पष्टीभविष्यति ॥ **वि[2]प्रतिषेधे पर**मिति शास्त्रपरत्वे तु ङित्वस्य सावकाशत्वोक्तिरसङ्गता स्यात्, सूत्रसावकाशत्वमेव हि विप्रतिषेधे बीजम् । न ह्यस्य सूत्रस्य सर्वादेशाप्राप्तिविषये कच्चिच्चारितार्थ्यम् । अवश्यप्राप्तिरेव च बाध्यत्वे बीजं दृष्टम् ॥ किंच विप्रतिषेधशास्त्रपरवार्तिकव्याख्यानपरभाष्यं शास्त्रद्वयावकाशप्रदर्शनशैली भाष्यकारस्य दृश्यते, न चात्र तथोक्तं भगवता ॥ यद्यप्यन्यत्रानुवादत्वं शास्त्रस्य दोष उक्तः, तथापि परिभाषाणां नियमरूपत्वेन तासु गुण एव । तत्र हि प्राप्तानुवादादेवेतरनिवृत्तिरर्थात् । यथा व्रीहीनवहन्तीत्यादौ प्राप्तावघातानुवादेन नखविदलनादिनिवृत्तिः । यथा च तस्मिन्नित्यादौ प्राप्तपूर्वस्येत्याद्यनुवादेन परादिनिवृत्तिः । किंच कप्-यप्-अवादिष्वनन्यार्थपित्त्वेषु चरितार्थस्यानुदात्तौ सुप्पितावित्यस्य जित्वरीत्यादौ तुक्संपादनेन चरितार्थपित्त्वे करपि अन्तरङ्गेण प्रत्ययाद्युदात्तत्वेन बाधापत्तिः, तदाह—**दौर्बल्यादिति** । परिभाषात्वभङ्गकृतं तदिति भावः ॥ **सन्दिग्धेति** । आपाततः सन्देहः, पर्यालोचने त्वनुपस्थितिरेवेति भावः । तदाह—**अपवादत्वमेवेत्यादि** । ङित्त्वसामर्थ्यकृतं हि तत्त्वमिति भावः ॥

(समाधानबाधकभाष्यम्)

प्रयोजनं नाम तद्वक्तव्यं, यन्नियोगतः स्यात् । यदि चायं नियोगतः सर्वादेशः स्यात्, तत एतत्प्रयोजनं स्यात् । कुतो नु खल्वेतत्-ङित्करणादयं सर्वादेशो भविष्यति, न पुनरन्त्यस्य स्यादिति ॥

(प्रदीपः) **प्रयोजनं नामेति** । सति सर्वादेशत्वे ङित्करणं गुणवृद्धिप्रतिषेधार्थं स्यात् । तदेव तु सर्वादेशत्वमलभ्यं, ङित्त्वादन्त्यस्यैव प्रसङ्गात्-इति भावः ॥ **ङित्करणादिति** । गुणवृद्धिप्रतिषेधार्थादिति भावः ॥

(उद्योतः) ननु ङित्त्वं सर्वादेशत्वद्वारा गुणबाधनाद्यर्थं वा, उतान्यत्र क्लृप्तसर्वादेशत्वबाधफलकं वेति शङ्कते-भाष्ये-**प्रयोजनं नामेति** ॥ **सति सर्वादेशत्वे इति** । अन्त्यादेशत्वे तु तत्संपादनेनैवावयवे ङित्वस्य चारितार्थ्येन समुदायोपकारकत्वे मानाभावात् प्रत्ययस्य ङित्वाभावेन न गुणादिप्रतिषेधप्राप्तिरित्यर्थः ॥ **ङित्त्वादिति** । गुणवृद्धिप्रतिषेधार्थत्वे सिद्धे सर्वादेशत्वम्, तस्मिंश्च तत्त्वम्, इत्यन्योन्याश्रयेण सर्वादेशत्वालाभेऽन्त्यस्यैव स्यादिति भावः ॥

(समाधानसाधकभाष्यम्)

एवंतर्ह्येतदेव ज्ञापयति-न तातङन्त्यस्य स्थाने भवतीति । यदेतं ङितं करोति । इतरथा हि लोट एवप्रकरण एव ब्रूयात्—"तिह्योस्तातङाशिष्यन्यतरस्याम्" इति ॥ ङिच्च ॥ ५३ ॥

(प्रदीपः) **एवंतर्हीति** । अन्तरेणापि ङित्त्वमेरुरित्यत्र प्रकरणे ताति विधीयमानेऽन्त्यादेशत्वं सिद्धमिति ङित्त्वादेव गुणवृद्धिप्रतिषेधार्थं ङित्त्वमिति ज्ञायते ॥ ५३ ॥

(उद्योतः) **अन्तरेणापीति** । तथा च तत्सामर्थ्यात् सर्वादेशत्वद्वारा गुणवृद्धिबाधनार्थत्वमेवास्येति भावः ॥ ५३ ॥

(४९ परिभाषासूत्रम् ॥ १ । १ । ७ आ. १० ॥)

आदेः परस्य ॥ १ । १ । ५४ ॥

(आदिनियमतःसर्वादेशबलीयस्त्वाधिकरणम्)

(३०४ सिद्धान्तवार्तिकम् ॥ १ ॥)

॥ * ॥ अलोऽन्त्यस्यादेः परस्यानेकाल्शित्सर्वस्येत्यपवादविप्रतिषेधात्सर्वादेशः ॥ * ॥

(भाष्यम्)

"अलोऽन्त्यस्य" इत्युत्सर्गः । तस्य "आदेःपरस्य" "अनेकाल् शित्सर्वस्य" इत्यपवादौ । अपवादविप्रतिषेधात् सर्वादेशो भविष्यति ॥

"आदेः परस्य" इत्यस्यावकाशः–"द्व्यन्तरुपसर्गेभ्योऽप ईत्" द्वीपम्, अन्तरीपम्, समीपम्। "अनेकाल् शित्सर्वस्य" इत्यस्याऽवकाशः–"अस्तेर्भूः" भविता, भवितुम् । इहोभयं प्राप्नोति–"अतो भिस ऐस्" । "अनेकाल् शित्सर्वस्य" इत्येतद्भवति विप्रतिषेधेन ॥

'शित्सर्वस्य' इत्यस्यावकाशः–"इदम इश्" इतः, इह । "आदेः परस्य" इत्यस्यावकाशः–स एव । इहोभयं प्राप्नोति–"अष्टाभ्य औश्" । "शित्सर्वस्य" इत्येतद्भवति विप्रतिषेधेन ॥ आदेः परस्य ॥ ५४ ॥

(५० परिभाषासूत्रम् ॥ १ । १ । ७ आ. ११)

अनेकाल् शित्सर्वस्य ॥ १ । १ । ५५ ॥

(शिद्ग्रहणप्रयोजनप्रत्याख्यानम्)

(आक्षेपभाष्यम्)

शित्सर्वस्येति किमुदाहरणम् ?

(प्रयोजनभाष्यम्)

"इदम इश्" इतः, इह ॥

(प्रयोजनबाधकभाष्यम्)

नैतदस्ति । शित्करणादेवात्र सर्वादेशो भविष्यति ॥

(प्रदीपः) अनेकाल्० ॥ ५५ ॥ शित्करणादेवेति । सति शकारेऽनेकाल्त्वादिति भावः ॥ अनेकाल्त्वसंपादनेन च कृतार्थः शकार इति-इत्संज्ञकत्वाँल्लुप्यते ।

(उद्द्योतः) अनेकाल् शित्० ॥५५॥ ननु शित्पदाभावे कथं 'शित्करणादेव' इति भाष्यमत आह—सतीति । शकारोच्चारणसामर्थ्याद् भूतपूर्वानेकाल्त्वमादाय शास्त्रप्रवृत्तिरिति भावः ॥ यत्त्वेतत्सामर्थ्याद् फलप्रत्यासत्तेश्च विधानोत्तरमेवेत्संज्ञादिशास्त्रप्रवृत्तिर्लक्ष्ये इति भाव इति ॥ तन्न । अणुदित्सूत्रे इशि सवर्णग्रहणापत्तिपरभाष्येण सूत्रे एवेत्संज्ञालोपप्रवृत्तेः सूचनात् ॥ नन्वेवं 'शकाराद्' इत्येव वक्तुं युक्तं, किमित्पदेनेति चेत् । न, फलान्तराभावेऽपि शकारोच्चारणस्य सप्रयोजनत्वाल्लोप एवेत्कार्यमिति शस्येत्त्वं प्रवर्तत इति सूचयितुं तथोक्तेः । तदाह—अनेकाल्त्वेति ॥

(प्रयोजनान्तरभाष्यम्)

इदं तर्हि–"अष्टाभ्य औश्" ॥

(प्रदीपः) अष्टाभ्य औशिति । आदेः परस्येत्यादेः प्राप्त इति भावः ॥

(प्रयोजनबाधकस्मारणभाष्यम्)

ननु चात्रापि शित्करणादेव सर्वादेशो भविष्यति ॥

(उद्द्योतः) भाष्ये—ननु चात्रापीति । अपवादविप्रतिषेधादिति भावः ॥

(प्रयोजनान्तरभाष्यम्)

इदं तर्हि–"जसः शी" "जश्शसोः शिः" ॥

(प्रयोजनबाधकस्मारणभाष्यम्)

ननु चात्रापि शित्करणादेव सर्वादेशो भविष्यति ॥

(प्रयोजनसाधकभाष्यम्)

अस्त्यन्यच्छित्करणे प्रयोजनम् ॥

किम् ?

विशेषणार्थः शकारः ॥

क्व विशेषणार्थेनार्थः ?

"शि सर्वनामस्थानम्" "विभाषा ङिश्योः" इति ॥

(उद्द्योतः) (भाष्ये) अस्त्यन्यदिति । एवंच तस्य प्रयोजनत्वेन भूतपूर्वगत्याश्रयणे मानाभावेन नानेकाल्त्वात् सर्वादेशत्वम्, अपि तु शित्त्वादेव–इति शिद्ग्रहणं सूत्रे कार्यमिति भावः ॥

('नानुबन्धकृतमनेकाल्त्वम्' इति परिभाषासाधनाधिकरणम्)

(वचनवैयर्थ्योपपादनभाष्यम्)

'शित्सर्वस्य' इति शक्यमकर्तुम् ॥

कथम् ?

अन्त्यस्यायं स्थाने भवन् प्रत्ययः स्यात् । असत्यां प्रत्ययसंज्ञायामित्संज्ञा न स्यात् । असत्यामित्संज्ञायां लोपो न स्यात् । असति लोपे अनेकाल् । यदा अनेकाल्, तदा सर्वादेशः ।

यदा सर्वादेशः, तदा प्रत्ययः । यदा प्रत्ययः, तदेत्संज्ञा । यदेत्संज्ञा, तदा लोपः ॥

(नानुबन्धकृतमनेकाल्त्वपरिभाषाज्ञापकभाष्यम्)

एवं तर्हि सिद्धे सति यत् 'शित्सर्वस्य' इत्याह तज्ज्ञापयत्याचार्यः—अस्त्येषा परिभाषा—"नानुबन्धकृतमनेकाल्त्वं भवति" इति ॥

किमेतस्य ज्ञापने प्रयोजनम् ?

तत्रासरूपसर्वादेशदाप्प्रतिषेधेषु पृथक्त्वनिर्देशोऽनाकारान्तत्वात् इत्युक्तम्, तन्न वक्तव्यं भवति ॥ अनेकाल्० ॥ ५५ ॥

इति श्रीमद्भगवत्पतञ्जलिविरचिते व्याकरणमहाभाष्ये प्रथमस्याध्यायस्य प्रथमे पादे सप्तममाह्निकम् ॥

(प्रदीपः) अन्त्यस्यायमिति । ननु सर्वनाम्नो नपुंसकादिति च पञ्चमीनिर्देशादादेः परस्येत्यादेर्भाव्यं तत्किमुच्यतेऽन्त्यस्यायं भवतीति । एवं तर्हि सर्वनाम्न इति षष्ठीं मन्यते नपुंसकादिति च विहितविशेषणमिति ज्ञापकत्वमेव शित्करणस्य । अथवा-असत्यपीह शिद्ग्रहणे अनेकाल्त्वादादेः परस्येति बाधित्वा सर्वादेशो भविष्यति किं शिद्ग्रहणेनेति

पुनरपि ज्ञापकमेव शिद्ग्रहणम् ॥ अनेकान्तेषु चानुबन्धेषु-नास्त्येव-**अनुबन्धकृतमनेकाल्त्वं**-इति । एकान्तेषु च ज्ञापकेन प्रयोजनम् ॥ ५५ ॥

इत्युपाध्याय**जैयट**पुत्र**कैयट**कृते महाभाष्य**प्रदीपे** प्रथमस्याध्यायस्य प्रथमे पादे **सप्तम**माह्निकम् ॥

(उद्योतः) सर्वादेशात्प्राक् प्रत्ययादित्वाभावेन नेत्त्वमिति प्रतिपादयितुं **अन्त्यस्याय**मित्यादि भाष्यम्, तदाक्षिपति—**नन्विति**। तैतश्च सर्वादेशत्वं विनाऽपि प्रत्ययादित्वाल्लभ्यत एवेत्त्वमिति भावः ॥ **षष्ठीमिति** । सर्वनामसंबन्धिनो जसः शी, नपुंसकाद्विहितयोर्जश्शसोः शिरिति चार्थः । एवं च परशब्देन परस्य विधानाभावान्न तत्प्रवृत्तिरिति भावः ॥ तयोः पैरशब्दयोगे पञ्चमीत्वेऽप्याह—**अथवेति**। असत्यपि सूत्रे शिद्ग्रहण इति अर्थः । श्यादयो यावन्नादेशास्तावन्नेत्त्वलोपौ । आदेशाश्च परत्वात्सर्वस्यैवेति भावः ॥ (भाष्ये) **नानुबन्धकृतमिति**। एवं च शीप्रभृतीनामपि शित्त्वादेव सर्वादेशत्वं, तस्याप्यनुबन्धत्वात् । न च विधानकाले उक्तरीत्या तस्य तत्त्वज्ञानाभावः, तद्योग्यतयैव तत्त्वात् । अन्यथा कप्रत्ययादीनां क्वादेर्वाक्यार्थबोधोत्तरं प्रत्ययत्वज्ञाने इत्संज्ञालोपाविति विधानकाले कस्यानुबन्धत्वज्ञानाभावेन **नानुबन्धकृतमसारूप्य**मित्यस्याप्राप्तौ विकल्पापत्तेः । शिदित्यस्यापीत्संज्ञायोग्यशकारवान्सर्वस्येत्यर्थ इति न दोष इति भाति ॥ **अस्त्येषा परिभाषेति** । अनुबन्धानामलव्यवहाराभावस्य ज्ञापनादिति भावः ॥ अत एवानुबन्धकार्येष्व**नल्विधा**विति स्थानिवत्त्वनिषेधो न । अन्यथा क्त्वो ल्यपः कित्त्वं न स्यात् ॥ न च पूर्वमनुबन्धलोपे तद्रहितस्यैव स्थानित्वात्तस्य न स्थान्यवयवत्वम् । सूत्रे स्थानषष्ठ्या निर्दिष्टस्यैव स्थानिपदवाच्यतया तदवयवत्वस्य ककारे सत्त्वात् । अन्यथाऽग्रहीदित्यादावि**ट ईटी**ति दीर्घो न स्यादिति **स्थानिवत्सूत्रे** निरूपयिष्यामः ॥ भाष्ये—**तत्रासरूपेति** । असरूपे कविषये णप्राप्तिर्दोषः । सर्वादेशे **दिव औ**दिति सर्वादेशः स्यादिति दोषः । प्रतिषेधे दैपो भेदेन निर्देशः कार्यः । तृतीये हेतु**रनाकारान्त**त्वादितीत्यर्थः ॥ ज्ञापकमनावश्यकमित्याह—**अनेकान्तेष्विति** ॥ **एकान्तेषु चेति** । अयमेव मुख्यः पक्ष इति **तस्य लोप** इत्यत्र भाष्ये स्पष्टम् ॥ ५५ ॥

इति श्री**शिवभट्टसुतसतीगर्भजनागोजीभट्ट**कृते भाष्यप्रदीपोद्योते प्रथमाध्यायस्य प्रथमे पादे **सप्तम**माह्निकम् ॥

अथ प्रथमाध्यायस्य प्रथमपादे अष्टममाह्निकम् ॥

(अतिदेशप्रकरणम्)

(५१ अतिदेशसूत्रम् ॥ १ । १ । ८ आ. १)

स्थानिवदादेशोऽनल्विधौ ॥ १।१।५६ ॥

(पदकृत्याधिकरणम्)

(आक्षेपभाष्यम्)

वत्करणं किमर्थम् ?

(प्रदीपः) स्थानिवत्० ॥ ५६ ॥ **वत्करणमिति** । विनाऽपि वतिना तदर्थलाभः, यथा क्ङिति दिति भावः । न च 'स्थान्यादेशः' इत्युच्यमाने स्थानिरूपमादेशः प्रतिपद्यते-इति कल्पनाऽऽश्रयितुं युक्ता, **अस्तेर्भू**रित्यादेशविधानवैयर्थ्यप्रसङ्गात् । न च वचनद्वयप्रामाण्याद्विकल्पः, **वा लिटी**ति विकल्पारम्भात् ॥

(उद्योतः) स्थानिवदादेशो० ॥ ५६ ॥ **स्थानिरूपमिति** । नै च **सिद्धं धर्मिण**मित्यादिन्यायेन पूर्वोच्चारितस्योद्देश्यत्वबोधकेन स्थान्यादेशरूपं प्रतिपद्यत इत्येवार्थो युक्त इति वाच्यम् । प्रसिद्धस्थानिनां प्रसिद्धादेशविधाने वैयर्थ्यापत्तेः । अन्यत्र विधाने तु **स्थानेऽन्तरतम** इति सूत्रोक्तन्यायेनाव्यवस्थापत्तेः, तस्ये न्यायस्य सूत्रकृताऽप्यत्र त्यागाच्च । अतै एव भाष्यकृता 'स्थानी संज्ञा' इत्येवोक्तं न तु 'आदेशः संज्ञा' इतीति बोध्यम् ॥ **वा लिटीति** । न च **चक्षिङः ख्याञि**त्यनेनानेन च सर्वत्रार्धधातुके ख्याञो विकल्पे सिद्धे 'लिट्येव वा' इति नियमार्थं स्यादिति वाच्यम् । दोषदुष्टनियमापेक्षयैतत्सूत्रे एतदतिरिक्तार्थकत्वज्ञापकताया एवौचित्यात् ॥

(समाधानभाष्यम्)

'स्थान्यादेशोऽनल्विधौ' इतीयत्युच्यमाने संज्ञाऽधिकारोऽयम्, तत्र स्थानी आदेशस्य संज्ञा स्यात् ॥

तत्र को दोषः ?

"आङो यमहनः" आत्मनेपदं भवतीति वधेरेव स्यात्, हन्तेर्न स्यात् । वत्करणे पुनः क्रियमाणे न दोषो भवति । स्थानिकार्यमादेशे अतिदिश्यते 'गुरुवद्गुरुपुत्रे' इति यथा ॥

(प्रदीपः) संज्ञाधिकार इति । संज्ञाप्रस्ताव इत्यर्थः ॥ **तत्र को दोष इति** । आदेशे कार्यसिद्ध्यर्थोऽतिदेशः । तच्चादेशे कार्यं संज्ञासंज्ञिसंबन्धेऽपि सिध्यतीति **प्रश्नः** ॥ **वधेरेवेति** । संज्ञा हि प्रदेशेषु संज्ञिप्रत्यायनार्था संज्ञिनं प्रत्याय्य निवर्तते, न तु स्वतः कार्यं प्रतिपद्यत इति भावः ॥ **बहुगणे**त्यत्र तु 'संख्या' इत्यन्वर्थताश्रयणाल्लौकिकार्थग्रहणात् विनाऽपि वतिनाऽतिदेशपक्ष उपन्यस्तः । वत्करणात्त्विहातिदेशे स्थानिकार्याण्यादेशे क्रियन्ते न तु स्थानिनि निवर्त्यन्ते-इत्यदोषः ॥ क्ङिति दिति तु संज्ञा न भवन्ति, **न क्त्वा सेडि**ति प्रतिषेधात् । न हि क्त्वः कित्संज्ञा विहिता, या प्रतिषिध्येत । **किकिनौ लिट् चे**त्यत्र तु संज्ञाप्रकरणाभावात् तद्वदतिदेशः ॥ **स्थानिकार्य**मित्यनेन कार्यातिदेशोऽयमिति दर्शयति । शास्त्राद्यतिदेशापेक्षया कार्यातिदेशस्य प्राधान्यात्, इतरेषां कार्यार्थत्वादिति भावः ॥

(उद्योतः) भाष्ये-**स्थानी आदेशस्येति** । **नवेती**त्यतः 'इति' शब्दानुवृत्तेः **स्थानिशब्दार्था** हनादय **आदेशपदार्थस्य** वधादेः संज्ञेत्यर्थः । स्थानिशब्दस्यादेशशब्दसंज्ञात्वे वैयर्थ्यमिति भावः ॥ ननु स्वरितलिङ्गकानुवृत्तिरूपाधिकारस्य संज्ञाविषयस्य शास्त्रेऽभावादाह—**प्रस्ताव इति** । प्रस्तावः-प्रकरणं, बुद्धिसंनिधिरिति यावत् । पूर्वोत्तरत्र प्रायेण संज्ञाया दर्शनादिति भावः ॥ परिभाषात्वं त्वनुक्तिसंभवग्रस्तमिति तन्नोक्तम् ॥ भाष्ये—**वधेरेवेति** । न चैव-

माङो वधयम इत्येवाकारविवक्षणेन स्वतन्त्रवधिभ्याहृत्तौ हन्ग्रहणं व्यर्थं स्यादिति वाच्यम् । 'आजघ्ने' इत्यादिसकलहन्स्यादेशसंग्रहार्थं तस्य सत्वात् ॥ हन्तेर्न स्यादिति । आहनिष्यत इत्यादौ ॥ नन्वत्र पादे वर्ति विनाऽतिदेशानवगतौ कथं बहुगणेत्यत्रातिदेशपक्ष उक्तोऽत आह—बह्विति ॥ सङ्ख्येवेति । सङ्ख्यापदस्येत्यर्थः ॥ लौकिकार्थग्रहणादिति । सङ्ख्यानकरणरूपेत्यर्थः । एवं च तद्वाधापस्या संज्ञात्वासंभवादतिदेश इति भावः ॥ इदं च तत्रैव सूत्रे कैयटे स्पष्टम् ॥ संज्ञा नेति । उभयगतेरिह शास्त्रे सत्त्वेन संज्ञात्वेऽपि ङिदादिग्रहणेन चङादीनामपि ग्रहणम् ॥ न हीति । अनुवृत्तकित्ग्रहणस्य संज्ञापरत्वेन सैव प्रतिषेध्या, न च सा क्त्वो विहितेत्यर्थः ॥ किंच किदित्यादेः संज्ञात्वे क्ङिति चेत्यत्रास्य ग्रहणं न स्यात्, संज्ञास्वरूपानुच्चारणादिति वोध्यम् । तथा निष्ठा शीङ्स्विदादिनिषेधोऽप्यसंबद्धः स्यात् । कित्साहचर्यात् ङिदित्यप्यतिदेशः ॥ कार्यातिदेशोऽयमिति । एवं चानपेक्षितशास्त्रमनपेक्षितनिमित्तं च प्रत्ययत्वादिरूपं कार्यमनेनैव क्रियते इति भावः ॥

(आक्षेपभाष्यम्)

अथादेशग्रहणं किमर्थम् ?

(प्रदीपः) **आदेशग्रहणमिति** । स्थानिशब्दस्य संबन्धिशब्दत्वादादेशो लभ्यत एव । यथा-पितृवदधीत इत्युक्ते पुत्र इति भावः ॥

(उद्द्योतः) भाष्ये—**यः स्थाने इति** स्थानशब्दप्रयोगात् तदनुवृत्त्याऽऽदेशो लभ्यत इति भ्रमं व्युदस्यति—**स्थानीति** ॥

(प्रत्याक्षेपभाष्यम्)

'स्थानिवदनल्विधौ' इतीयत्युच्यमाने क इदानीं स्थानिवत्स्यात् ?

यः स्थाने भवति ॥

कश्च स्थाने भवति ?

आदेशः ॥

(प्रदीपः) **क इदानीमिति** । द्विविध आदेशः—प्रत्यक्षश्चास्तेर्भूरित्यादिः, आनुमानिकश्चैरुरित्यादिः । अत्र हि—इकारेणेकारान्तः स्थान्यनुमीयते, उकारेणोकारान्त आदेशः । ततस्नेस्तुरिति संपद्यते । तत्र प्रत्यक्षस्यैव ग्रहणं स्यात्, नानुमानिकस्येति भावः ॥

(उद्द्योतः) नन्वादेशलब्धौ 'कः' इति प्रश्नानुपपत्तिरित्यत आह—**द्विविध इति** ॥ केचित्तु स्थानिशब्दस्य संबन्धिशब्दत्वमजानतः प्रश्नः—**क इति** ॥ संबन्धिशब्दत्वाभिप्रायमुत्तरं—**यः स्थाने इति** ॥

(समाधानभाष्यम्)

इदं तर्हि प्रयोजनम्—आदेशमात्रं स्थानिवद्यथा स्यात् । एकदेशविकृतस्योपसंख्यानं चोदयिष्यति, तन्न वक्तव्यं भवति ॥

(प्रदीपः) **आदेशमात्रमिति** । प्रत्यक्षमनुमितं चेत्यर्थः । पटुरित्यत्र प्रत्यक्षमुकारस्यादेशत्वमिकारस्य च स्थानित्वम् । न च किंचिदिकारस्य कार्यमस्ति यदुकारेऽतिदिश्येत । तिशब्दकार्यं तु तुशब्दस्यातिदिश्यत इति पदत्वसिद्धिः ॥

(उद्द्योतः) समाधत्ते—**आदेशमात्रमिति** । अस्याशयः कैयटोक्त एव ॥ कैयटोक्तव्याख्यानेऽपि 'यः स्थाने' इत्यादिग्रन्थस्याशयानभिज्ञवक्तृकतयैव योज्यमानत्वादित्याहुः ॥ नन्वत्रापि प्रत्यक्षस्यैव स्थानिवत्त्वमस्त्वित्यत आह—**न चेति** ॥ **पदत्वेति** । अत एव 'देवदत्तः पचतु' इत्यत्र पदस्येत्यधिकृत्य विधीयमानो निघातः सिध्यति । 'पचतु ते ओदनं' इत्यत्र पदादित्यधिकृत्य विधीयमानस्तेमयादिश्च सिध्यति ॥

(आक्षेपभाष्यम्)

अथ विधिग्रहणं किमर्थम् ?

(उद्द्योतः) भाष्ये—**विधिग्रहणं किमर्थमिति** । 'विधौ' इत्यध्याहाराल्लप्स्यत इति प्रश्नः ॥

(विधिग्रहणप्रयोजनभाष्यम्)

सर्वविभक्त्यन्तः समासो यथा विज्ञायेत—अलः परस्य विधिः—अल्विधिः, अलो विधिः—अल्विधिः, अलि विधिः—अल्विधिः, अला विधिः—अल्विधिरिति ॥

(प्रदीपः) **सर्वविभक्त्यन्त इति** । सर्वविभक्त्यन्तोऽवयवोऽस्यास्तीति मत्वर्थीयोऽकारः । बहुत्वप्रतिपादनपरमेतत् । न ह्यत्र सप्त विभक्तयः संभवन्ति । तत्र संबन्धमात्रे षष्ठ्युपादानेऽनेकविभक्त्यर्थान्तर्भावात् फलतः सर्वविभक्त्यन्तता संभवति । **अथवा**—अल्विधिशब्दवाच्योऽल्विधिरिति विशिष्टप्रवृत्तिनिमित्ताश्रयणात् सर्वविभक्त्यन्तत्वम् । सति च विधिशब्दे समासभावादेतद्वस्तुलाभः । केवलस्त्वल्शब्द उपादीयमानो यद्विभक्त्युच्चार्येत तदर्थोपक्षय एव स्यात् । तत्रालः परस्य विधिः—द्यौः- पन्थाः - सः - इति, सुलोपो न भवति ॥ अलि परतो विधिः—क इष्टः - स इष्टः - इति, हशि चेत्युत्वं न भवति ॥ अलो विधिः—द्युकाम इति, लोपो व्योर्वलीति लोपो न भवति ॥ उत्वं त्ववलि सावकाशं स्यात्—अहर्विमलद्यु इति ॥ अला विधिः—महोरस्केनेति । **अयोगवाहानामट्सूपदेशाण्णत्वं** न भवतीति ॥

(उद्द्योतः) ननु समासोत्तरं सप्तम्या एव श्रवणेन सर्वविभक्त्यन्तत्वं समासस्यानुपपन्नमत आह—**अवयव इति** । पूर्वपदरूप इत्यर्थः ॥ ननु विभक्तिचतुष्टयेनैव विग्रहस्याग्रे प्रदर्शनेन सर्वेत्यनुपपन्नमत आह—**बहुत्वेति** । द्वितीयाचतुर्थीप्रथमाभिः स्थान्यलः सूत्रेऽनिर्देशादिति भावः ॥ ननु सकृच्छ्रुतेऽल्विधिपदे कथमल्पदस्यानेकविभक्त्यन्ततेत्यत आह—**तत्रेति** । विधिशब्दः कर्मसाधनः । तेनाल्संबन्धिकार्ये-इत्यर्थः ॥ प्रौढ्या पक्षान्तरमाह—**अथवेति** । अल्शब्दात्परो विधिशब्दः-अल्विधिशब्दः, तेन च तद्वाच्योऽर्थो लक्ष्यत इति भावः ॥ एवं च तद्वाच्यत्वेन रूपेण सर्वार्थाश्रयणात्सर्वविभक्त्यन्तत्वे यत्फलं तत्फलसिद्धिरिति तात्पर्यम् ॥ **समासभावादिति** । उपदर्शितपक्षद्वयोक्तसमासभस्त्वादित्यर्थः ॥ **यद्विभक्तिरिति** । षष्ठ्युपादानेऽपि स्थानसंबन्ध एव बुध्येतेति भावः ॥ **तदर्थोपक्षय एव स्यादिति** । तदर्थमात्रान्वितार्थक एव स्यादित्यर्थः ॥ **इष्ट**

इति । यजे. क्तः । यद्यपि 'क इष्टः' इति रूपमुभयेऽपि सिध्यति, तथापि 'कविष्टः' इति पक्षे स्यात् 'कयिष्टः' इति न स्यादिति बोध्यम् । 'स इष्टः' इत्यत्र एतत्तदोरिति नित्यो लोपः स्यादिति च बोध्यम् ॥ दिवि कामोऽस्य-द्युकामः । 'दिव उत्' । यद्यपि वत्वं हस्वत्वाद्यपेक्षया विशेषधर्मस्तथापि एतद्वाक्योपप्लुतवकारवदुकार इति वाक्योपात्तधर्मापेक्षया न तत्त्वम् । सूत्रकृतस्थान्यादेशभावमादायैव हि एतत्कृतवाक्योपप्लव इति दिक् ॥ उपदेशादिति । तस्य स्थानिवत्त्वेन विसर्गत्वाद्विसर्गस्य चाद्रूपदेशेनाद्गत्वादिति भावः ॥

(विधिग्रहणप्रयोजननिरासभाष्यम्)

नैतदस्ति प्रयोजनम् । प्रातिपदिकनिर्देशोऽयम् । प्रातिपदिकनिर्देशाश्चार्थतन्त्रा भवन्ति, न कांचित्प्राधान्येन विभक्तिमाश्रयन्ति । तत्र प्रातिपदिकार्थे निर्दिष्टे यां यां विभक्तिमाश्रयितुं बुद्धिरुपजायते सा सा आश्रयितव्या ॥

(प्रदीपः) प्रातिपदिकनिर्देशाश्चेति । 'अनल्' इत्येतावदेवोच्यताम् । अत्र शब्दसंस्काराय केवलं प्रथमाविभक्तिरुपादीयते । न तु तदर्थो विवक्ष्यते । यथा 'भावे' इत्यत्र लिङ्गसंख्ये इति भावः ॥

(उद्योतः) केवलप्रकृतेः प्रयोगाभावादाह—अत्रेति ॥ विवक्ष्यते इति । तत्समभिव्याहारे प्रतीयमानो विधेयत्वरूपोऽर्थो न विवक्ष्यत इत्यर्थः ॥ अन्वयायोग्यत्वादिति भावः ॥ लिङ्गेति ॥ अत एव 'भूतिः' इत्यादिसिद्धिः ॥ सप्तम्यर्थस्तु तत्र विवक्षित एवेति लिङ्गसंख्ये इत्येवोक्तम् ॥ भाष्ये—अर्थतन्त्रा इति । स्वार्थमात्रबोधकविभक्त्यधीना इत्यर्थः ॥ प्राधान्येन विभक्ति—विशिष्य प्रकृतान्वययोग्यविभक्त्यर्थं नाश्रयन्ति ॥ निर्दिष्टे—बोधिते । पश्चादन्वययोग्यविभक्त्यर्थाकाङ्क्षायां यद्यद्विभक्त्यर्थमन्वयित्वेनाश्रयितुं लक्ष्यानुसाराद्बुद्धिरुपजायते सा सा विभक्तिरध्याहार्या । साधुत्वार्थमुत्पन्नविभक्तेस्तु लुगिति भावः ॥ एतेन प्रत्ययाध्याहारो न क्वापि दृष्ट इत्यपास्तम् । मा भेर्मा संविक्था इति पुरोडाशावदानमन्त्रस्य धानास्वहे मा भैष्ट मा संविग्ध्वमित्यादौ दर्शनाच्च । तत्तद्विषयकलक्षणभेदात्तत्र तत्र सा आश्रयितव्येति तात्पर्यम् ॥ न चानलिति प्रथमानिर्देशेऽनलात्मक आदेश इत्यर्थे ल्यपोऽनलात्मकत्वेन 'प्रपठ्य' इत्यादाविट् स्यात् । उत्तमपुरुषैकवचने टेरेत्वस्य स्थानिवत्त्वाभावात्पदत्वं न स्यादिति चेन्न । अदो जग्धिरिति सूत्रे ल्यप्ग्रहणेनादेशविशेषणत्वाभावज्ञापनादित्यदोषः ॥

(विधिग्रहणप्रयोजनान्तरभाष्यम्)

इदं तर्हि प्रयोजनम्—उत्तरपदलोपो यथा विज्ञायेत । अलमाश्रयते अलाश्रयः, अलाश्रयो विधिः—अल्विधिरिति । यत्र प्राधान्येनालाश्रीयते तत्रैव प्रतिषेधः स्यात् । यत्र विशेषणत्वेनालाश्रीयते तत्र प्रतिषेधो न स्यात् ॥

किं प्रयोजनम् ?

प्रदीव्य-प्रसीव्येति वलादिलक्षण इट् मा भूदिति ॥

(प्रदीपः) उत्तरपदलोप इति । 'अनल्' इत्युच्यमाने यत्र कार्ये स्वातन्त्र्येणालाश्रीयते, तत्रैव निषेधः स्यात्—क इष्टः-स इष्ट इत्यादौ । प्रदीव्येत्यादौ इटः प्रतिषेधो न स्यात् । न ह्यिड्विधौ वलः स्वातन्त्र्येणाश्रयणम्, वलादेरित्यन्यपदार्थस्य प्राधान्याद्गुणभावाद्वलः । उत्तरपदलोपे त्वलाश्रयत्वादिड्विधेः प्रतिषेधसिद्धिः ॥ अलमाश्रयत इति । अर्थप्रदर्शनमेतत् । एवं हि 'अलाश्रायः' इति स्यात् । तस्मात्-आश्रीयत इत्याश्रयः, एरच् । अलाश्रयो विधिरल्विधिः । अलाश्रयत्वाद्विधिरेवाल्वित्युच्यत इति गतार्थत्वादप्रयोग एव उत्तरपदस्य लोपः ॥

(उद्योतः) स्वातन्त्र्येण—प्राधान्येन । सैकलविधिपरिग्रहार्थविधिशब्देन प्रधानन्यायो बाध्यत इति भावः ॥ एवं हीति । कर्मण्यणा पचाद्यचो बाधादिति भावः ॥ शब्दानित्यत्ववारणाय वार्तिकप्रत्याख्यानाय चाह—अप्रयोग एवेति ॥ भाष्ये—यत्रप्राधान्येनेत्यस्य विधिग्रहणाभावे इत्यादिः । प्रतिषेधो न स्यादित्यस्य तदर्थं विधिग्रहणमिति शेषः ॥

(लौकिकन्यायेन सूत्रार्थसाधनम्)

(सूत्राक्षेपभाष्यम्)

किमर्थं पुनरिदमुच्यते ?

(प्रदीपः) किमर्थमिति । तत्स्थानापत्त्या तद्धर्मलाभात् स्थानिकार्याण्यादेशः प्राप्स्यतीति भावः ॥

(३०५ समाधानवार्तिकम् ॥ १ ॥)

॥ * ॥ स्थान्यादेशपृथक्त्वादादेशे स्थानिवदनुदेशो गुरुवद् गुरुपुत्र इति यथा ॥ * ॥

(भाष्यम्)

अन्यः स्थानी, अन्य आदेशः । स्थान्यादेशपृथक्त्वादेतस्मात्कारणात् स्थानिकार्यमादेशे न प्राप्नोति ॥

तत्र को दोषः ?

"आङो यमहनः" आत्मनेपदं भवतीति हन्तेरेव स्यात्, वधेर्न स्यात् । इष्यते च—वधेरपि स्यादिति । तच्चान्तरेण यत्नं न सिध्यति । तस्मात्स्थानिवदनुदेशः । एवमर्थमिदमुच्यते ॥

'गुरुवद् गुरुपुत्र इति यथा' । तद्यथा—गुरुवदस्मिन् गुरुपुत्रे वर्तितव्यम्-इति । गुरौ यत्कार्यं तद् गुरुपुत्रेऽतिदिश्यते । एवमिहापि स्थानिकार्यमादेशेऽतिदिश्यते ॥

(प्रदीपः) स्थान्यादेशपृथक्त्वादिति । स्थानिस्वरूपाश्रयं यत्कार्यं तद्भिन्नरूपत्वादादेशे न सिध्यतीति भावः ॥

(उद्योतः) ननु पृथक्त्वमङ्गीकृत्यैव तत्स्थानापत्त्या तद्धर्मलाभेऽभिहिते स्थान्यादेशपृथक्त्वादिति हेतुरसङ्गतोऽत आह—स्थानिस्वरूपेति । स्वं रूपमित्युक्तेर्न तत्स्थानापत्त्या शास्त्रे तत्कार्यलाभ इति भावः ॥

(सूत्रारम्भप्रयोजनबाधकभाष्यम्)

नैतदस्ति प्रयोजनम् । लोकत एतत् सिद्धम् । तद्यथा—लोके यो यस्य प्रसङ्गे भवति, लभतेऽसौ तत्कार्याणि । तद्यथा—उपाध्यायस्य शिष्यो याज्यकुलानि गत्वा अग्रासनादीनि लभते ॥

(प्रदीपः) लोकत इति । लोके हि वचनमन्तरेणापि तत्स्थानापत्त्या तद्धर्मलाभो दृष्टः ॥ उपाध्यायस्येति । प्रसङ्गापेक्षेयं षष्ठी । न तु शिष्यस्य विशेषणमेतत्, व्यभिचाराभावात् ॥

(उद्द्योतः) व्यभिचाराभावादिति । तत्स्थानापत्त्या तद्धर्मलाभे दृष्टान्तोऽसङ्गतः स्यादिति च बोध्यम् ॥ यद्यप्युपनीय सर्ववेदाध्यापकरूपाचार्यशिष्यव्यावृत्तये उपाध्यायस्येति तद्विशेषणमावश्यकम्, वेदैकदेशाध्यापको ह्युपाध्यायः । तथापि तद्व्यावृत्तौ प्रयोजनाभाव इत्यभिप्रायेणेदमिति बोध्यम् ॥ अत्र भाष्ये लोकत एतत्सिद्धमित्युक्त्वा स्वंरूपमिति शास्त्रादादेशे न स्यादिति सूत्रं कार्यमित्युक्तम् । तेन स्वं रूपमिति शास्त्रविषये लोकन्यायेन सिद्धमिति सूचितम् ॥ अनल्विधाविति निषेधोऽपि शास्त्रीयस्थानिवद्भाव एव । अतिप्रसङ्गस्तु लक्ष्यानुसारेण क्वचिल्लोकन्यायानाश्रयणेन परिहरणीयः । एवं च 'लोलुवः' इत्यादावनादिष्टादचः पूर्वत्वं लोकन्यायेन भवत्येवेति केचित् ॥

(सूत्रारम्भप्रयोजनसाधकभाष्यम्)

यद्यपि तावल्लोक एष दृष्टान्तः । दृष्टान्तस्यापि तु पुरुषारम्भो निवर्तको भवति ॥

(आक्षेपभाष्यम्)

अस्ति चेह कश्चित्पुरुषारम्भः ?

(समाधानभाष्यम्)

अस्तीत्याह ॥

कः ?

स्वरूपविधिर्नाम । हन्तेरात्मनेपदमुच्यमानं हन्तेरेव स्यात्, वधेर्न स्यात् ॥

(सूत्रारम्भप्रयोजननिराकरणभाष्यम्)

एवं तर्ह्याचार्यप्रवृत्तिर्ज्ञापयति—स्थानिवदादेशो भवतीति । यदयं "युष्मदस्मदोरनादेशे" इत्यादेशे प्रतिषेधं शास्ति ॥

कथं कृत्वा ज्ञापकम् ?

युष्मदस्मदोर्विभक्तौ कार्यमुच्यमानं कः प्रसङ्गो यदादेशे स्यात् । पश्यति त्वाचार्यः—स्थानिवदादेशो भवति । अत आदेशे प्रतिषेधं शास्ति ॥

(सूत्रारम्भप्रयोजनभाष्यम्)

इदं तर्हि प्रयोजनम्—अनल्विधाविति प्रतिषेधं वक्ष्यामीति । इह मा भूत्—द्यौः-पन्थाः-सः-इति ॥

(प्रदीपः) प्रतिषेधं वक्ष्यामीति । न ह्यप्रदर्शितविषयः प्रतिषेधः शक्यो विधातुमिति भावः ॥

(उद्द्योतः) अप्रदर्शितविषयः—अप्रदर्शितप्रतिषेध्यः ॥ ननु युष्मदस्मदोरनादेश इत्यत्र विभक्तिविषये स्वं रूपमित्यस्य लोकन्यायबाधकस्याप्राप्त्या तत्र लोकन्यायेन प्राप्ततद्धर्मलाभप्रयुक्तकार्यनिवारणेन चरितार्थस्य अनादेशग्रहणस्य ज्ञापकत्वासंभवात् हनो वधेत्यादौ दोषवारणायेदं सूत्रमावश्यकमिति चेत्, न । स्वादिसूत्रे स्वं रूपमित्यस्य प्रवृत्त्या तत्स्वरूपाणामेव सुप्संज्ञकत्वेन तेषामेव विभक्तिसंज्ञकत्वेन तत्र 'तत्स्थानापत्त्या तद्धर्मलाभः' इति लौकिकन्यायाप्रवृत्तेरित्याशयात् ॥

(सूत्रारम्भप्रयोजननिराकरणभाष्यम्)

एतदपि नास्ति प्रयोजनम् । आचार्यप्रवृत्तिर्ज्ञापयति—अल्विधौ स्थानिवद्भावो न भवतीति, यदयम्—"अदो जग्धिर्ल्यप्ति किति" इति 'ति किति' इत्येव सिद्धे ल्यब्ग्रहणं करोति । तस्मान्नार्थोऽनेन योगेन ॥

(प्रदीपः) एवं तावल्लिङ्गेनाभिमतोऽर्थः सिद्ध इति प्रदर्शितम् ॥

(सूत्रेसत्त्वेऽनल्विधिग्रहणवैयर्थ्यनिराकरणम्)

(वार्तिकोपक्रमभाष्यम्)

आरभ्यमाणेऽप्येतस्मिन् योगे—

(३०६ वैयर्थ्याक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ अल्विधौ प्रतिषेधेऽविशेषणेऽप्राप्तिस्तस्यादर्शनात् ॥ * ॥

(भाष्यम्)

अल्विधौ प्रतिषेधेऽसत्यपि, विशेषणे समाश्रीयमाणे, असति तस्मिन् विशेषणे अप्राप्तिर्विधेः । प्रतीव्य, प्रदीव्य ॥

किं कारणम् ?

'तस्यादर्शनात्' । वलादेरित्युच्यते । न चात्र वलादिं पश्यामः ॥

(प्रदीपः) इदानीं क्रियमाणेऽपि सूत्रेऽनल्विधाविति न कर्तव्यमित्याह—अल्विधौ प्रतिषेध इति । 'प्रपठ्य' इतीद् न भवति । इड्विधौ वलादेरिति विशेषणमाश्रितम् । तच्च 'क्त्वो ल्यप्' इति वस्तुस्थित्या संनिहितमपि वलादित्वं स्थानिन्यविवक्षितत्वादनाश्रितम् । तथाहि—इडादिरपि क्त्वा भवत्येव, केवलोऽपि, आकारान्तोऽपि, स्नात्वीतीकारान्तोऽपि, दत्त्वायेति च यगन्तोऽपि, इष्ट्वीनमिति मान्तोऽपि । तत्र क्त्वामात्रप्रतिबद्धं यत्कार्यं कृत्त्वप्रत्ययत्वादि तदादेशेऽतिदिश्यताम्, न तु वलादित्वमिति ल्यपो न स्वतो नापि स्थानितो वलादित्वमितीडभावः सिद्ध एवेति भावः ॥

(उद्द्योतः) क्रियमाणेऽपीति । मन्दमत्यनुग्रहायेत्याशयः ॥ न पदान्तेत्यत्र निषेध्यसमर्पणाय नावश्यकं तदिति बोध्यम् ॥ अनल्विधाविति न कर्तव्यमित्यस्य विधिपदघटितं न कर्तव्यमित्यर्थः ॥ असत्यपि-इति भाष्ये छेदः । अल्विधौ प्रतिषेधे

इत्यस्य चैतद्विशेषणम् । अप्राधान्येनाल्‌आश्रयणेऽपि निषेधार्थं क्रियमाणे विधिग्रहणेऽसत्यपीत्यर्थः ॥ वार्तिके—**अविशेषणे**–इति च्छेदः, लक्ष्ये विशेषणाभावे - इति तदर्थः । तदाह—**विशेषणे समाश्रीयमाण इति** । विधाविति शेषः ॥ **असतीत्यादेः**–प्रयोग इति शेषः ॥ **सामान्यातिदेशे विशेषानतिदेश** इति हेतुं व्याचक्षाणो वलादित्वस्य विशेषत्वं दर्शयति—**तच्चेति** ॥ **अविवक्षितत्वादिति** । विवक्षाकारणयत्नविशेषनिषयीकृतत्वाभावादित्यर्थः ॥ उपात्तरूपव्याप्यरूपविवक्षा हि यत्ने सत्येव भवति । अत एव **सनि** मीत्यत्र सः सीत्यतः सीत्यनुवर्तितम् । न च तथा कश्चिद्यत्नः प्रकृते । एवं च 'वलादेरादेशो वलादिवत्' इत्येवं वाक्यकल्पनाऽत्र नेति भावः ॥ तत्र वलादित्वस्य क्त्वाव्याप्यत्वं दर्शयितुमाह—**तथाहीति** । आकारान्तोऽपीत्यादि दृष्टान्तार्थम् ॥ **यत्कार्यमिति** । यो धर्म इत्यर्थः । 'क्त्वावत् ल्यप्' इत्येव वाक्यकल्पनेति भावः ॥

(वार्तिकावतरणभाष्यम्)

ननु चैवमर्थ एवायं यत्नः क्रियते—अन्यस्य कार्यमुच्यमानमन्यस्य यथा स्यादिति ॥

सत्यम् । एवमर्थो यत्नः क्रियते, न तु प्राप्नोति ॥ किं कारणम्?

(उद्योतः) 'सामान्यातिदेशे' इत्यादिवार्तिकखण्डमवतारयति—**ननु चेति** ॥ भाष्ये–एवमर्थशब्दं व्याचष्टे—**अन्यस्येति** ।

(३०७ वैयर्थ्याक्षेपसाधकवार्तिकम् ॥ २ ॥)

॥ * ॥ सामान्यातिदेशे हि विशेषानतिदेशः ॥ * ॥

(भाष्यम्)

सामान्ये ह्यतिदिश्यमाने विशेषो नातिदिष्टो भवति । तद्यथा—'ब्राह्मणवदस्मिन् क्षत्रिये वर्तितव्यम्' इति । सामान्यं यद् ब्राह्मणकार्यं, तत् क्षत्रियेऽतिदिश्यते । यद्विशिष्टं माठरे कौण्डिन्ये वा, न तदतिदिश्यते । एवमिहापि सामान्यं यत्प्रत्ययकार्यं तदतिदिश्यते, यद्विशिष्टं वलादेरिति न तदतिदिश्यते ॥

(प्रदीपः) ब्राह्मणवदिति । सामान्यशब्दोपादानेन यत्र कार्यमतिदिश्यते, तत्र विशेषस्याशब्दार्थत्वाद्विशेषाश्रयकार्यानतिदेशः । यत्र तु विशेषशब्दोपादानेनातिदेशस्तत्र विशेषातिदेशो भवत्येव ॥

(उद्योतः) अशब्दार्थत्वादिति । यद्यपि 'क्त्वावत्' इत्युक्तेऽशब्दार्थप्रत्ययत्वादेरप्यतिदेशो भवति तथापि व्याप्येन व्यापकानुमानात्तदुपस्थितिवद्व्याप्योपस्थितौ मानाभाव इति भावः ॥ **यत्र त्विति** । गोतो णिदित्यादौ ॥

(वैयर्थ्यबाधकसिद्धान्तिभाष्यम्)

यद्येवं—अग्रहीत्, "इट ईटि" इति सिचो लोपो न प्राप्नोति ॥

अनल्विधाविति पुनरुच्यमाने इहापि प्रतिषेधो भविष्यति—प्रदीव्य-प्रसीव्येति, विशिष्टं ह्येषोऽलमाश्रयते वलं नाम । इह च प्रतिषेधो न भविष्यति अग्रहीदिति, विशिष्टं ह्येषोऽनलमाश्रयते इटं नाम ॥

(प्रदीपः) अग्रहीदिति । 'ग्रहोऽलिटि दीर्घः' इति दीर्घे कृत इति भावः ॥ दीर्घविधौ ह्यच्परिभाषोपस्थानादच एव स्थानित्वम् । इट् त्वजन्तराणां व्यावर्तक इतीट्कार्यं विशेषकार्यत्वान्न प्राप्नोति ॥ तथा प्रदीव्येति गुणप्रतिषेधो न प्राप्नोति । देवित्वेत्यादावकितोऽपि क्त्वाप्रत्ययस्य संभवात् कित्त्वस्यापि वलादित्ववन्न स्यादतिदेशः ॥ तस्माद्विशेषकार्यातिदेशज्ञापनार्थमनल्विधाविति कर्तव्यमिति भावः । अनुबन्धकार्येषु चा**नल्विधा**विति प्रतिषेधो न प्रवर्तते, स्थानिन्यनुबन्धस्यासन्निधानात् । असन्त एवानुबन्धाः कार्यस्य विशेषका इति सिद्धान्तव्यवस्थापनात् ॥ **विशिष्टं ह्येषोऽनलमिति** । 'इट ईटि' इति सलोपे समुदायरूपेणाश्रयणात् 'ग्रहोऽलिटि दीर्घः' इत्यत्रापि इट एव स्थानित्वं नाचः । अनियमाप्रसङ्गान्नियमफलाया अच्परिभाषाया अनुपस्थानात् ॥

(उद्योतः) अथ सिद्धान्ती विशेषानतिदेशे दूषणं वदन् तं ज्ञापनार्थमेवानल्विधावित्यावश्यकमित्याह–भाष्ये–**यद्येवमिति** । यदि विशेषानतिदेश इत्यर्थः ॥ **दीर्घे कृते इति** । दीर्घदृष्ट्यां सिज्लोपस्यासिद्धत्वादिति भावः ॥ ननु दीर्घस्य 'इट्' इति समुदायस्थानिकत्वेन तद्वृत्तीट्त्वाश्रयो लोपः स्थानिवत्त्वेन स्यादेव, स्थानी चादेशविधावुपात्त एवेत्यत आह—**दीर्घेति** ॥ नन्वच एव स्थानित्वे 'ग्रहणं' इत्यादावपि दीर्घः स्यादत आह—**इट् त्विति** ॥ (भाष्ये) **सिचो लोपो न प्राप्नोतीत्यस्य तस्मादनल्विधाविति वक्तव्य**मिति शेषः ॥ विशेषानतिदेशे दूषणान्तरमाह—**तथेति** ॥ **अकितोऽपीति** । न क्त्वा सेडिति कित्त्वनिषेधादिति भावः ॥ **तस्मादिति** । न च 'क इष्टः' 'धुभ्याम्' इत्यादिव्यावृत्त्या तस्य चारितार्थ्यात्कथं ज्ञापकत्वमिति वाच्यम् । अप्राधान्येनाप्यल्‌आश्रयणे आर्धधातुकस्येडित्यादौ निषेधप्रवृत्तये क्रियमाणं विधिग्रहणं प्रकृतार्थज्ञापकम् । विशेषानतिदेशे तेषामसंग्रहेण तद्वैयर्थ्यस्य स्पष्टत्वात् ॥ वार्तिकेऽपि विधिपदघटिते प्रतिषेधेऽसत्यपीत्यर्थः ॥ ज्ञापिते विशेषातिदेशेऽनल्विधावित्यस्य चारितार्थ्यं दर्शयति— भाष्ये–**इहापि प्रतिषेधेत्यादि** ॥ ननु कित्त्वस्याल्विधित्वेन क्ङिति चेति निषेधे स्थानिवत्त्वाभावात् 'प्रतिदीव्य' इत्यादौ गुणः स्यादत आह—**अनुबन्धेति** ॥ **स्थानिनीति** । स्थान्यल्‌आश्रये विधौ स्थानिवत्त्वनिषेधादिति भावः ॥ **न ल्यपीति** लिङ्गमप्यत्र बोध्यम् ॥ नन्वेवमप्यग्रहीदिति दीर्घस्थानिभूताज्रूपैकाश्रय एव सिज्लोपः, अनुबन्धस्तु उपदेश एव लुप्त इति तत्रापि स्थानिवत्त्वनिषेधः स्यादतो भाष्ये–**विशिष्टं ह्येष इति** । एवं च 'दीर्घ इड्वत्' इत्येवातिदेशकल्पना, स्थानितावच्छेदकं च शास्त्रोपात्तरूपमेव । तच्च नाल्रूपमिति इट इत्यादि न स्थान्यल्वृत्तिधर्माश्रयम् । **एवं च यत्र शास्त्रे विशेष्यतया विशेषणतया वा आदेशस्थानिभूतो योऽल् तत्स्थानिसंबन्धी वा योऽल् तन्मात्रवृत्तिधर्माश्रयणं तादृशे विधौ हि निषेधः** । अत्र च शब्दतो विशिष्ट-

मनल्माश्रयते । वलादेरित्यत्र च शब्दतो विशिष्टमल्मिति भावः ॥ सिद्धान्तव्यवस्थापनादिति । इदं निरनुबन्धकानुवादेन विहितादेशविषयम् । क्त्वो ल्यबित्यादौ सानुबन्धकानुवादेनादेशविधौ तु यथाऽनुबन्धकार्यस्याल्विधित्वाभावस्तथाऽनेकाल्शिदित्यत्र निरूपितम् ॥ अत्रापीट एव स्थानित्वमिति । अन्यथा स्थान्यल्वृत्तीट्त्वाश्रयस्य लोपस्याल्विधित्वात्तत्र स्थानिवत्त्वानापत्तिर्विशेषातिदेशेऽपीति भावः ॥ एवं च तदुदाहरणे विशेषानतिदेशेऽपि न दोषः । एतदेवाभिप्रेत्य स्वयं 'प्रदीव्य' इति गुणापत्तिर्विशेषानतिदेशे दूषणमुक्तम् । वस्तुतो भाष्योक्तदोषोऽपि दृढ एव । तथाहि—अनल्विधावित्यस्याभावे प्रायोगिकस्थानिनमादायैव वाक्योपप्लवः स्यात् । तद्बुद्धि निवर्त्यैवादेशबुद्धेर्जायमानत्वेन तस्यैव मुख्यस्थानित्वात् । यद्येवमित्यस्य विशेषानतिदेशमाश्रित्य विधिग्रहणाकरणे-इत्यर्थः । एवं च दीर्घस्थान्यल्परस्य कार्यं लोप इति स्थानिवद्भावेन तदप्राप्तिरिति पूर्वपक्षः ॥ 'विधौ' इत्युक्तौ तु न दोषः, शास्त्रस्योपस्थित्या शास्त्रोपात्तस्थान्यादेशभावस्य निमित्तस्य च ग्रहणमिति न दीर्घोऽल्विधिरित्युत्तरम् ॥ तदेतदेषोऽनल्मित्यनेन दीर्घादिविधिरित्यर्थकेन ध्वनितमिति बोध्यम् । अत एव भोभगोअघो इति सूत्रे भाष्ये रेफस्थानिकविसर्गस्य स्थान्यल्वृत्तिधर्मरुत्वाश्रयं कार्यं न, अल्विधित्वादित्युक्तम् ॥

(आक्षेपवार्तिकादिशेषभाष्यम्)

यदि तर्हि सामान्यमप्यतिदिश्यते, विशेषश्च ॥

(३०८ आक्षेपसाधकं वार्तिकम् ॥ ३ ॥)

॥ * ॥ सत्याश्रये विधिरिट् ॥ * ॥

(भाष्यम्)

सति च वलादित्वे इटा भवितव्यम् । अरुदिताम् । अरुदितम् । अरुदित ॥

(उक्ताशयानभिज्ञभाष्यम्)

किमतो यत्सति भवितव्यम् ?

(३०९ आक्षेपवार्तिकम् ॥ ४ ॥)

॥*॥ प्रतिषेधस्तु प्राप्नोत्यल्विधित्वात् ॥*॥

(भाष्यम्)

प्रतिषेधस्तु प्राप्नोति ॥

किं कारणम् ?

'अल्विधित्वात्' । अल्विधिरयं भवति । तत्रानल्विधाविति प्रतिषेधः प्राप्नोति ॥

(प्रदीपः) **सत्याश्रय इति ।** आश्रीयत इत्याश्रयः । यथा वलादित्वमिड्विधौ । तत्रेडागमस्याल्विधित्वादनल्विधौ च स्थानिवद्भावविधानादरुदितामिति स्थानिकार्यमिडागमो न प्राप्नोति ॥

(उद्द्योतः) भाष्ये-**यदि तर्हि सामान्यमिति ।** अनल्विधाविति ज्ञापकात् । तज्ज्ञापनार्थं चानल्विधाविति यदि क्रियत इत्यर्थः ॥ आश्रयशब्दस्य भावसाधनत्वे 'वलादित्वे' इति तद्विवरणमसंगतं स्यादत आह—आश्रीयत इति ॥ स्थानिकार्यमिति । सार्वधातुकत्वाभावादिति भावः ॥ भाष्ये—प्रतिषेधस्त्विति । आदेशः स्थानिवत्, अलाश्रये विधौ तु न-इति सूत्रार्थ इति भावः ॥

(३१० सिद्धान्तिसमाधानवार्तिकम् ॥ ५ ॥)

॥ * ॥ न वाऽऽनुदेशिकस्य निषेधादितरेण भावः ॥ * ॥

(भाष्यम्)

न वा एष दोषः ॥

किं कारणम् ?

आनुदेशिकस्य प्रतिषेधात् । अस्त्वत्रानुदेशिकस्य वलादित्वस्य प्रतिषेधः । स्वाश्रयमत्र वलादित्वं भविष्यति । नैतद्विवदामहे-वलादिर्न वलादिरिति ॥

किं तर्हि ?

स्थानिवद्भावात् सार्वधातुकत्वमेषितव्यम् ॥

(प्रदीपः) **न वेति ।** अतिदेश एवानुदेशः, स प्रयोजनं यस्य तदानुदेशिकम् । तत्र स्वाश्रयं वलादित्वमाश्रित्य स्थान्याश्रयं च सार्वधातुकत्वमिड्विधास्यते ॥

(उद्द्योतः) समाधत्ते—न वेति । स प्रयोजनं-प्रयोजको यस्य वलादित्वस्येत्यर्थः । करणे ल्युट् । पदसंस्कारपक्षाश्रयेण तु अतिदेशः प्रयोजनमिति प्रयुक्तम् ॥ शङ्किताऽऽह-नैतद्विवदामह इति ॥

(आक्षेपोपसंहारभाष्यम्)

तत्रानल्विधाविति प्रतिषेधः प्राप्नोति ॥

(प्रदीपः) **तत्रानल्विधाविति ।** इडागमार्थमत्र स्थानिवद्भावः प्रार्थ्यते । इट् चाल्विधिरिति अनल्विधाविति प्रतिषेधात् सार्वधातुकत्वस्यापीडर्थत्वादिड् न प्राप्नोतीति ॥

(उद्द्योतः) ननु सार्वधातुकत्वस्याल्धर्मत्वाभावात् कथं प्रतिषेधप्राप्तिरत आह—इडागमेति ॥

(स्थान्यलाश्रयविधौ प्रतिषेधसाधनम्)

(आक्षेपभाष्यम्)

किं पुनरादेशिन्यल्याश्रीयमाणे प्रतिषेधो भवति, आहोस्विदविशेषेण-आदेशे, आदेशिनि च ?

कश्चात्र विशेषः ?

(प्रदीपः) इदानीं यथाऽत्र प्रतिषेधो न प्रवर्तते तथा विचारपूर्वकं प्रतिपादयितुमाह—**किं पुनरिति ।** आदेशोऽस्यास्तीत्यादेशी-स्थानी । किं स्थान्यलाश्रये कार्ये स्थानिवत्त्वनिषेधः, अथाल्मात्राश्रय इति विचारः । किं प्रत्यासत्तिराश्रीयते. अथवा व्याप्तिरिति भावः ॥

(उद्द्योतः) उक्तदोषमपरिहृत्य विचारान्तरारम्भोऽनुपपन्न इत्यत आह—इदानीमिति ॥ प्रतिपादयितुमिति । वादिमुखे-

नैव प्रतिपादयितुमित्यर्थः ॥ आदेशोऽस्येति । आदेशिनीति अलीत्यनेन व्यधिकरणं, स्थानिसम्बन्ध्यलाश्रय इत्यर्थः । सम्बन्धिन एवाधिकरणत्वविवक्षया सप्तमी । अत एव स्थानित्वे तु व्यपदेशिवद्भावेन तत्त्वमिति बोध्यम् ॥ सन्देहबीजं दर्शयति—किमिति ॥

(३११ प्रथमपक्षाक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ आदेश्यल्विधिप्रतिषेधे कुरुवधपिबां गुणवृद्धिप्रतिषेधः ॥ * ॥

(भाष्यम्)

आदेश्यल्विधिप्रतिषेधे कुरुवधपिबां गुणवृद्ध्योः प्रतिषेधो वक्तव्यः ॥

कुर्वित्यत्र स्थानिवद्भावादङ्गसंज्ञा, स्वाश्रयं च लघूपधत्वम् । तत्र लघूपधगुणः प्राप्नोति ॥

वधक इत्यत्र स्थानिवद्भावादङ्गसंज्ञा, स्वाश्रयं चातुपधत्वम् । तत्र वृद्धिः प्राप्नोति ॥

पिबेत्यत्र स्थानिवद्भावादङ्गसंज्ञा, स्वाश्रयं च लघूपधत्वम् । तत्र गुणः प्राप्नोति ॥

(प्रदीपः) वधक इति । हन्तेर्ण्वुलि 'बहुलं संज्ञाछन्दसोरिति वक्तव्यम्, अन्नवधकगात्रविचक्षणाजिराद्यर्थम्' इति वधादेशः । स च हलन्त इति दोषोपन्यासः । अदन्तत्वे त्वल्लोपस्य स्थानिवद्भावाद्वृद्ध्यभावः ॥

(उद्योतः) स्थानिवद्भावादिति । अचः परस्मिन्नित्यनेन । एवं चोपधात्वाभावो ञ्णितपरत्वाभावश्चेति भावः ॥

(द्वितीयपक्षाङ्गीकारभाष्यम्)

अस्तु तर्ह्यविशेषेण-आदेशौ आदेशिनि च ॥

(३१२ द्वितीयपक्षाक्षेपवार्तिकम् ॥ २ ॥)

॥ * ॥ आदेश्यादेश इति चेत् सुप्तिङ्कृदतिदिष्टेषूपसंख्यानम् ॥ * ॥

(भाष्यम्)

आदेश्यादेश इति चेत्सुप्तिङ्कृदतिदिष्टेषूपसंख्यानं कर्तव्यम् ॥

सुप् । वृक्षाय, प्लक्षाय । स्थानिवद्भावात्सुप्संज्ञा, स्वाश्रयं च यञादित्वम् । तत्र प्रतिषेधः प्राप्नोति ॥

अरुदिताम्, अरुदितम्, अरुदित । स्थानिवद्भावात्सार्वधातुकसंज्ञा, स्वाश्रयं च वलादित्वं । तत्र प्रतिषेधः प्राप्नोति । तिङ् ॥

कृदतिदिष्ट । भुवनं, सुवनं, धुवनम् । स्थानिवद्भावात्प्रत्ययसंज्ञा, स्वाश्रयं चाजादित्वम् । तत्र प्रतिषेधः प्राप्नोति ॥

(प्रदीपः) सुप्तिङ्कृदतिदिष्टेष्विति । आदिष्ट एवातिदिष्टो विवक्षितः ॥ उपलक्षणं चैतत् । तद्धितादेशेष्वपि न प्राप्नोति—लैगवायन इति । अत्र हि स्वाश्रयमजादित्वं स्थानिवद्भावात्तद्धितत्वम् ॥

(उद्योतः) अतिदेशः—अतिदिष्टं चेदर्थासङ्गतिरत आह—आदिष्ट एवेति । सुबादीनामादेशेष्वित्यर्थः । तेषु दीर्घत्वे इटि उवङि च स्थानिवत्त्वप्रतिषेधः प्राप्नोति ॥ तद्धितत्वमिति । भस्य तद्धिते ओर्गुणविधानादिति भावः ॥

(तटस्थाक्षेपभाष्यम्)

किं पुनरत्र ज्यायः ?

(प्रदीपः) किं पुनरिति । न्यायापेक्षः प्रकर्षः । कः पक्षो न्यायोपपन्न इत्यर्थः ॥

(उद्योतः) ननु पक्षद्वयेऽपि दोषोक्तेः कस्यापि प्रशस्तत्वाभावाद् आतिशयिकोऽनुपपन्न इत्यत आह—न्यायेति । युक्त इत्यर्थः ॥ का युक्तिः प्रकृष्टा—इत्यत्र प्रश्नतात्पर्यमिति भावः ॥

(समाधानभाष्यम्)

'आदेशिन्यल्याश्रीयमाणे प्रतिषेधः' इत्येतदेव ज्यायः ॥

कुत एतत् ?

तथा ह्ययं विशिष्टं स्थानिकार्यमादेशोऽतिदिशति—'गुरुवद् गुरुपुत्रे' इति यथा । तद्यथा—'गुरुवदस्मिन्गुरुपुत्रे वर्तितव्यम्, अन्यत्रोच्छिष्टभोजनात्पादोपसंग्रहणाच्च' इति । यदि च गुरुपुत्रोऽपि गुरुर्भवति । तदपि कर्तव्यं भवति ॥

(प्रदीपः) आदेशिनीति । प्रत्यासत्त्येति भावः ॥ यत्कार्यमादेशः स्वतो न प्रतिपद्यते तत्र स्यादतिदेशाकाङ्क्षा । तच्छेषश्च प्रतिषेधस्तद्द्वारक एवाल्कार्ये युक्तः ॥ अरुदितामित्यत्र त्वादेशस्य स्वतो वलादित्वान्न तत्रातिदेशं प्रत्याकाङ्क्षा । सार्वधातुकत्वं तस्य स्वतो नास्तीति तदेवातिदेशेन प्राप्यते । यथा गुरुपुत्रो गुरुत्वे सति नातिदेशमपेक्षते, तथा वलादित्वं प्रत्यादेशस्य नास्त्यतिदेशापेक्षेत्येतावता दृष्टान्तः । सार्वधातुकत्वं प्रत्यस्त्येवातिदेशापेक्षा ॥

(उद्योतः) प्रत्यासत्त्येति । अत एव कष्टायेत्यादिनिर्देशाः सङ्गच्छन्ते । एवं च प्रत्यासत्त्याश्रयणमेव न्याय्यमिति भावः ॥ भाष्ये-विशिष्टं स्थानिकार्यमिति । स्वरूपेणालभ्यमानमित्यर्थः ॥ तदाह—यत्कार्यमिति ॥ तच्छेषः—अतिदेशशेषः ॥ तद्द्वारके—अतिदेशद्वारके ॥ यथेति । एवं च यथा तत्रातिदेशप्राप्तोच्छिष्टभोजनस्यैव वर्जनं, न तु स्वाश्रयगुरुत्वप्राप्तस्य, एवमलंशेऽतिदेशप्राप्ताल्विधेरेव वर्जनमिति भावः ॥

(प्रथमपक्षाभ्युपगमभाष्यम्)

अस्तु तर्हि-आदेशिन्यल्याश्रीयमाणे प्रतिषेधः ॥

(उक्ताक्षेपस्मारणभाष्यम्)

ननु चोक्तम्—*आदेश्यल्विधिप्रतिषेधे कुरुवधपिबां गुणवृद्धिप्रतिषेधः* इति ॥

(आक्षेपनिराकरणभाष्यम्)

नैष दोषः । 'करोतौ तपरनिर्देशात् सिद्धम्' । पिबिरदन्तः । वधक इति नायं ण्वुल् । अन्योऽयमकशब्दः किदौणादिकः, रुचक इति यथा ॥

(प्रदीपः) करोताविति । अकारस्य छुकारो मात्रिक एव न्याय्य इति शास्त्रान्तरेणापि प्राप्तस्य भिन्नकालस्य निवृत्त्यर्थं तपरत्वमित्यर्थः ॥ अन्योऽयमिति । हनो वध चेति कुन्प्रत्ययः ॥

(उद्द्योतः) भाव्यमानस्य सवर्णग्राहकत्वस्वीकारेऽपि तपरत्वं व्यर्थमित्याह—अकारस्येति । अन्तरतमत्वादिति भावः ॥ ऋकारस्थानिकावयवविकारोऽत्र इति लक्ष्यभेदात् 'उदवोढाम्' इतिवल्लक्ष्ये लक्षणस्येति न्यायेनात्र निर्वाह इत्याहुः । कुन्—औणादिकः ॥

(एकदेशविकृतन्यायाधिकरणम्)

(२१३ आक्षेपवार्तिकम् ॥ १ ॥)

॥*॥ एकदेशविकृतस्योपसंख्यानम् ॥*॥

(भाष्यम्)

एकदेशविकृतस्योपसंख्यानं कर्तव्यम् ॥
किं प्रयोजनम्?
पचतु, पचन्तु । तिङ्ग्रहणेन ग्रहणं यथा स्यात् ॥

(प्रदीपः) एकदेशविकृतस्येति । एकदेशेन विकृत इति तृतीयासमासः ॥

(उद्द्योतः) बहुव्रीहौ निष्ठान्तस्य पूर्वनिपातः स्यादत आह—तृतीयेति । आनुमानिकेऽपि स्थानिवत्त्वप्रवृत्तिर्वक्तव्येत्येतद्वार्तिकतात्पर्यम् ॥

(समाधाने भाष्यवार्तिकम् ॥)

॥एकदेशविकृतस्यानन्यत्वात्सिद्धम् ॥

(भाष्यम्)

'एकदेशविकृतमनन्यवद्भवति' इति तिङ्ग्रहणेन ग्रहणं भविष्यति । तद्यथा—श्वा कर्णे वा पुच्छे वा छिन्ने श्वैव भवति, नाश्वो न गर्दभ इति ॥

(प्रदीपः) तद्यथेति । छिन्नेऽपि पुच्छे शिष्टावयवसन्निवेशः श्वत्वजातेरभिव्यञ्जकः । एवं पचत्वित्यत्रेकारस्य विकारेऽपि तकारस्तिङ्त्वस्य व्यञ्जकः । तथा चेकारलोपेऽप्यपचदिति तकारमात्रस्य तिङ्त्वमर्थप्रतीतिहेतुत्वं चास्ति ॥ नाश्व इति । अवयवापगमेऽपि न तस्य जात्यन्तरेण योगः, किं तर्हि श्वत्वेनैवेत्यर्थः ।

(उद्द्योतः) लोकन्यायाश्रयेणैतत्प्रत्याचष्टे—अनन्यत्वात् सिद्धमिति—भाष्ये ॥ नन्ववयवविगमे जात्यभिव्यञ्जकाभावात्कथं 'श्वा' इति व्यवहारोऽत आह—छिन्नेऽपीति । तथा चेति । लोपस्य विकारत्वाभावेनैकदेशविकृतोपसंख्यानेऽपि तत्रोक्तरीतिरेवावश्यकीति भावः ॥ अर्थेत्यादि दृष्टान्तार्थः । अन्यथा शक्ततावच्छेदकानुपूर्व्यज्ञानाद्बोधो न स्यात् । एतदर्थं च तन्न्यायाङ्गीकार आवश्यक इति भावः ॥

(२१४ एकदेश्याक्षेपसाधकवार्तिकम् ॥ २ ॥)

॥ * ॥ अनित्यविज्ञानं तु तस्मादुपसंख्यानम् ॥ * ॥

(भाष्यम्)

अनित्यविज्ञानं तु भवति । नित्याः शब्दाः । नित्येषु नाम शब्देषु कूटस्थैरविचालिभिर्वर्णैर्भवितव्यमनपायोपजनविकारिभिः । तत्र स एवायं, विकृतश्च - इत्येतन्नित्येषु नोपपद्यते । तस्मादुपसंख्यानं कर्तव्यम् ॥

(प्रदीपः) अनित्यविज्ञानमिति । अवस्थिते तकारे इकारस्य उकार इत्यनित्यत्वं शुन इव प्राप्नोतीति भावः ॥ उपसंख्याने तु क्रियमाणे नास्त्यनित्यत्वम्, एरुरिति स्थान्यादेशाभ्यां तिशब्दतुशब्दयोरनुमीयमानत्वात्तेः प्रसङ्गे तोर्विधानात् । तत्रादेशग्रहणाद्वा उपसंख्यानाद्वा आनुमानिकस्याप्यादेशस्य स्थानिवद्भावः सिद्धः ॥

(उद्द्योतः) अवस्थिते इति । न च इप्रसङ्गे उरिति भाष्यमिति नानित्यत्वम्, अनर्थकत्वेनार्थबोधाय प्रसङ्गस्य वक्तुमशक्यत्वात् । अवयवत्वेन प्रसङ्गे त्ववयवान्तरप्रादुर्भावपूर्वावयवापगमाभ्यामनित्यत्वं स्यादित्यर्थः ॥ स एवायमिति प्रत्यभिज्ञया भाष्ये नित्यत्वमुपलक्षितम् । अत एव विकृत इत्यनेन विरोधः । अनित्यत्वाभावे हेतुः—तेः प्रसङ्गे इत्यादि । अस्य सार्थकत्वात् तेः प्रसङ्गे इत्युक्तिर्नासमञ्जसेत्यर्थः ॥ तदुपपादकम्—एरुरित्यादि । एवं च कार्यशब्दवादे न्यायेन सिद्धम्, नित्यशब्दवादे तु नेति वचनारम्भवादितात्पर्यम् ॥ वस्तुतो वचनारम्भेऽपि विकृतत्वबुद्धिमात्रेण तत्संगतिरित्यवश्यं वाच्यम् । अन्यथा विकृतस्येत्यसंगतं स्यात् । तदा तयैव रीत्या लोकन्यायप्रवृत्तिरपि सूपपादेति ॥ अनित्यविज्ञानं त्वित्याद्येकदेश्युक्तिः ॥

(ऋष्यन्तरसंवादभाष्यम्)

भारद्वाजीयाः पठन्ति—

(भारद्वाजीयवार्तिकम्)

॥*॥ एकदेशविकृतेषूपसंख्यानम् ॥*॥

(भाष्यम्)

एकदेशविकृतेषूपसंख्यानं कर्तव्यम् । पचतु, पचन्तु । तिङ्ग्रहणेन ग्रहणं यथा स्यात् ॥
किंच कारणं न स्यात्?

(भारद्वाजीयवार्तिकम्)

॥ * ॥ अनादेशत्वात् ॥ * ॥

(भाष्यम्)

आदेशः स्थानिवदित्युच्यते । न चेमे आदेशाः ॥

(भारद्वाजीयवार्तिकम्)

॥ रूपान्यत्वाच्च ॥

(भाष्यम्)

अन्यत्खल्वपि रूपं पचतीति, अन्यत्पचत्विति ॥

(प्रदीपः) **न चेम इति** । तुशब्दादयः, **पप्तुरित्यत्र** साक्षात्समुदायानुपादानात् ॥ **रूपान्यत्वाच्चेति** । यद्ययमवयवादेशो रूपं न भिन्द्यात्स्यादेव प्रत्यभिज्ञानात्तिङ्त्वम् । यतस्तु भेदको रूपस्य तस्मान्नास्ति तिङ्त्वमिति भावः ॥

(उद्द्योतः) कात्यायनीयात् भारद्वाजीयपाठे हेत्वभिधानं बहुवचनं च विशेषः ॥ **पप्तुरित्यत्रेति** । प्रत्यक्षादेशत्वं चेह निषेध्यमिति भावः ॥ लोकन्यायेन सिद्धिखण्डनाय—**रूपान्यत्वाच्चेति** ॥ तद्याचष्टे—**यदीति** । **इदमो म** इत्यादिवदिति भावः । अर्थस्यान्यथाभावेन जात्यभिव्यञ्जकाभाव इति तात्पर्यम् । **एकदेशविकृतेष्विति** बहुवचनेन लोपस्यापि सङ्ग्रहात् 'अपचत्' इत्यादावपि स्थानिवत्त्वमिति बोध्यम् ॥

(आक्षेपनिराकरणभाष्यम्)

इमेऽप्यादेशाः ॥

कथम् ?

आदिश्यते यः स आदेशः । इमे चाप्यादिश्यन्ते ॥

(उद्द्योतः) भाष्ये वचनं खण्डयति—**इमेऽपीति** । आनुमानिकादेशस्याप्यादेशपदसामर्थ्येन ग्रहणादिति भावः ॥ इममाशयमजानानः पृच्छति—**कथमिति** । उक्तेनैवाभिप्रायेणाह—**आदिश्यत इति** ॥ **इमे चेति** । तुशब्दादयः ॥

(३१५ आक्षेपसाधकवार्तिकम् ॥ ३ ॥)

॥ * ॥ आदेशः स्थानिवदिति चेन्नानाश्रितत्वात् ॥ * ॥

(भाष्यम्)

आदेशः स्थानिवदिति चेत् । न ॥

किं कारणम् ?

'अनाश्रितत्वात्' । योऽत्रादेशो नासावाश्रीयते । यश्चाश्रीयते नासावादेशः ॥

(प्रदीपः) **योऽत्रादेश इति** । इकारस्य उकारः । **नासावाश्रीयते**—पदसंज्ञायाम् । सा हि तिशब्दनिबन्धना, नावयवनिबन्धना ॥ **यश्चेति** । तुशब्दः । साक्षादविधानान्नादेशः । पदसंज्ञानिमित्तभावेन चाश्रीयत इत्यर्थः ॥

(उद्द्योतः) आदेशपदसामर्थ्यमजानान् आह—**आदेश** इत्यादि । प्रत्यक्षादेशस्यैव ग्रहणं न्याय्यमित्यभिमानः ॥ तदाह—**योऽत्रेति** । ननु तामादेः पदसंज्ञायामनाश्रयणेऽपि यथा स्थानिवत्त्वात्पदत्वमेवमुकारस्यापीत्यत आह—**सा हीति** । तेश्च नायमादेश इति भावः ॥ तिङ्त्वं समुदायपर्याप्तमिति तात्पर्यम् । स्थानिवत्त्वद्वाराऽपि नायमुकारः पदत्वहेतुतयाऽऽश्रीयत इति भाष्यार्थः ॥ **आश्रीयते** इत्यर्थ इति । आश्रयितुमिष्यत इत्यर्थः ॥

(आक्षेपबाधकभाष्यम्)

नैतन्मन्तव्यम्—'समुदाय आश्रीयमाणेऽवयवो नाश्रीयते' इति । अभ्यन्तरो हि समुदायेऽवयवः ।

तद्यथा—वृक्षः प्रचलन्सहावयवैः प्रचलति ॥

(प्रदीपः) तत्रोत्तरमाह—**नैतदिति** । 'तिप्-तस्-झि' इति सन्निवेशे इकारतकारावपि सन्निविष्टावितीकारस्य तिङ्त्वात्तदादेशस्याप्युकारस्य तिङ्त्वमिति सिद्धा पदसंज्ञा ॥

(उद्द्योतः) **तत्रोत्तरमाहेति** । एकदेशीति शेषः ॥ भाष्ये—**समुदाये इत्यादि** । सुप्तिङन्तमित्यादौ 'ति' इति समुदाये निमित्तत्वेनाश्रितेऽवयवातिरिक्तसमुदायाभावात् तकारेकारान्तं पदमित्यर्थः । एवं चेकारस्योकारादेशे स्थानिवद्भावेनेकारबुद्धौ निमित्तभूतसमुदायसत्त्वात्पदत्वं सिद्धमिति भावः ॥ **तिङ्त्वात्**—तदवच्छिन्नावयवत्वात् । तिङ्त्वं—तदवच्छिन्नावयवैकारत्वमित्यर्थः । यथाश्रुते हि पचतीत्यादौ तान्तस्यापि पदत्वापत्तौ जश्त्वापत्तिरिति बोध्यम् ॥

(३१६ आक्षेपवार्तिकम् ॥ ४ ॥)

॥*॥ आश्रय इति चेदल्विधिप्रसङ्गः ॥*॥

(भाष्यम्)

आश्रय इति चेदल्विधिरयं भवति । तत्रानल्विधाविति प्रतिषेधः प्राप्नोति ॥

(प्रदीपः) **अल्विधिप्रसङ्ग इति** । इकारस्य पदसंज्ञानिमित्तत्वादल्विधिः पदसंज्ञा स्यादित्यर्थः ॥

(आक्षेपबाधकभाष्यम्)

नैष दोषः । नैवं सति कश्चिदनल्विधिः स्यात् । उच्यते चेदं-अनल्विधाविति । तत्र प्रकर्षगतिर्विज्ञास्यते—साधीयो योऽल्विधिरिति ॥

कश्च साधीयः ?

यत्र प्राधान्येनालाश्रीयते । यत्र नान्तरीयकोऽलाश्रीयते नासावल्विधिरिति ॥

(प्रदीपः) **यत्र प्राधान्येनेति** । यत्र साक्षादल् निर्दिष्टः, तत्र प्रतिषेधः, नानुमीयमाने सम्भवमात्रेणालीत्यर्थः । प्राधान्यग्रहणं प्रत्यक्षोपलक्षणम् ॥

(उद्द्योतः) ननु प्राधान्येनेत्युक्तौ 'प्रदीव्य' इति न सिध्येदत आह—**यत्रेति** ॥ **प्रत्यक्षेति** । अनान्तरीयकेत्यर्थः ॥

(सिद्धान्तिसमाधानभाष्यम्)

अथवोक्तमादेशग्रहणस्य प्रयोजनम्—आदेशमात्रं स्थानिवद्यथा स्यादिति ॥

(प्रदीपः) **आदेशमात्रमिति** । आनुमानिकमपीत्यर्थः ॥

(उद्द्योतः) इदानीं सिद्धान्ती एकदेश्युक्तमैनुमन्यमान इव पक्षान्तरत्वेन स्वाशयं प्रकाशयति—भाष्ये—**अथवेति** ॥

(शब्दनित्यत्वेऽप्यनुपपत्तिपरिहारः)

(३१७ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ अनुपपन्नं स्थान्यादेशत्वं नित्यत्वात् ॥ * ॥

(भाष्यम्)

स्थानी आदेश इत्येतन्नित्येषु शब्देषु नोपपद्यते ॥

किं कारणम् ?

'नित्यत्वात्' । स्थानी हि नाम—यो भूत्वा न भवति । आदेशो हि नाम—योऽभूत्वा भवति ।

एतच्च नित्येषु शब्देषु नोपपद्यते—यत्सतो नाम विनाशः स्यात्, असतो वा प्रादुर्भाव इति ॥

(प्रदीपः) अनुपपन्नमिति । एकदेशविकारेऽपि यत्र नित्यत्वहानिस्तत्र सर्वविकारे कुतो नित्यत्वम् । यत्रान्वयोऽपि कस्यचिन्नास्तीत्यर्थः ॥

(उद्द्योतः) सर्वविकार इति । अस्तेर्भूरित्यादौ ॥ यो भूस्वेत्यादिभाष्यस्य–प्रागभावाप्रतियोगित्वे सति ध्वंसाप्रतियोगित्वं नित्यत्वमिति तात्पर्यम् ॥

(११८ समाधानवार्तिकम् ॥ २ ॥)

॥ * ॥ सिद्धं तु यथा लौकिकवैदिकेष्वभूतपूर्वेऽपि स्थानप्रयोगात् ॥ * ॥

(भाष्यम्)

सिद्धमेतत् ॥

कथम्?

यथा लौकिकवैदिकेषु कृतान्तेषु अभूतपूर्वेऽपि स्थानशब्दप्रयोगो वर्तते । लोके तावत्—'उपाध्यायस्य स्थाने शिष्यः' इत्युच्यते, न च तत्र उपाध्यायो भूतपूर्वोऽपि भवति ॥ वेदेऽपि—'सोमस्य स्थाने पूतीकतृणान्यभिषुणुयात्' इत्युच्यते । न च तत्र सोमो भूतपूर्वो भवति ॥

(प्रदीपः) सोमस्येति । सोमस्तृणविशेषः ॥ तदसन्निधौ पूतीकतृणानि प्रतिनिधीयन्ते ॥

(उद्द्योतः) स्थानशब्दः–प्रसङ्गवाचीत्युत्तरम् ॥ तदसंनिधाविति । नित्यस्यावश्यकर्तव्यत्वादारब्धस्य चावश्यसमापनीयत्वादिति भावः ॥

(समाधानान्तरभाष्यवार्तिकम् ॥)

॥ कार्यविपरिणामाद्वा सिद्धम् ॥

(भाष्यम्)

अथवा कार्यविपरिणामाद्वा सिद्धमेतत् ॥

किमिदं कार्यविपरिणामादिति?

कार्या-बुद्धिः, सा विपरिणम्यते ॥

(प्रदीपः) कार्या बुद्धिरिति । अन्यस्यात्र विपरिणामासम्भवात्सामर्थ्यात्कार्यत्वेन बुद्धिर्गृह्यते न तु कार्यशब्दो बुद्धिपर्यायः ॥

(प्रयोगासिद्धिभाष्यम्)

ननु च कार्याविपरिणामादिति भवितव्यम् ॥

(प्रयोगसाधकभाष्यम्)

सन्ति चैव ह्यौत्तरपदिकानि ह्रस्वत्वानि ॥

(प्रदीपः) सन्तीति । ङ्यापोरित्यत्र बहुलग्रहणात् ।

(उद्द्योतः) संज्ञाछन्दसोरुभयोरभावादाह —बहुलेति ॥

(प्रयोगसाधकयुक्त्यन्तरभाष्यम्)

अपि च 'बुद्धिः-संप्रत्ययः' इत्यनर्थान्तरम् । कार्या-बुद्धिः कार्यः-संप्रत्ययः । कार्यस्य-संप्रत्ययस्य विपरिणामः । कार्यविपरिणामादिति ॥

(समाधानान्तरबाधकभाष्यम्)

परिहारान्तरमेवेदं मत्वा पठितम् ॥

(उपपत्तिप्रश्नभाष्यम्)

कथं चेदं परिहारान्तरं स्यात्?

(समाधानान्तरबाधकभाष्यम्)

यदि भूतपूर्वे स्थानशब्दो वर्तते ॥

(उद्द्योतः) भूतपूर्वे स्थानशब्दप्रयोगमभ्युपेत्येदं परिहारान्तरम् । अन्यथाऽऽनर्थक्यप्रसङ्गात् ॥ न च तत्र स्थानशब्दो दृश्यते, सोमस्थाने इत्यादावभूतपूर्वे एव प्रयोगदर्शनादिति यदि भूतपूर्वे इत्यादिभाष्यतात्पर्यम् ॥

(समाधानान्तरसाधकभाष्यम्)

भूतपूर्वे चापि स्थानशब्दो वर्तते ॥

कथम्?

बुद्ध्या । तद्यथा कश्चित्कस्मैचिदुपदिशति—प्राचीनं ग्रामादाम्राः' इति । तस्य सर्वत्राम्रबुद्धिः प्रसक्ता । ततः पश्चादाह—'ये क्षीरिणोऽवरोहवन्तः पृथुपर्णास्ते न्यग्रोधाः' इति । स तत्राम्रबुद्ध्या न्यग्रोधबुद्धिं प्रतिपद्यते । स ततः पश्यति-बुद्ध्या आम्राँश्चापकृष्यमाणान्, न्यग्रोधांश्चोपाधीयमानान् । नित्या एव च स्वस्मिन्विषये आम्राः, नित्याश्च न्यग्रोधाः । बुद्धिस्त्वस्य विपरिणम्यते । एवमिहापि अस्तिरस्यायविशेषेणोपदिष्टः, तस्य सर्वत्रास्तिबुद्धिः प्रसक्ता । सः "अस्तेर्भूः" इत्यनेनास्तिबुद्ध्या भवतिबुद्धिं प्रतिपद्यते । स ततः पश्यति—बुद्ध्या अस्तिं चापकृष्यमाणं, भवतिं चोपाधीयमानम्, नित्य एव च स्वस्मिन्विषयेऽस्तिर्नित्यो भवतिश्च । बुद्धिस्त्वस्य विपरिणम्यते ॥

(प्रदीपः) भूतपूर्वे चापीति । न च नित्यत्वविरोधः । बुद्धिधर्माः केवलमर्थेषु प्रतिपत्तृवशादारोप्यन्ते, न तु तद्वशादर्थानां तथाऽवस्थानम् ॥ प्राचीनमिति । प्राचि देशे-प्राक् । ततो विभाषाञ्चेरदिक्स्त्रियामिति स्वार्थे खः । तत्र सप्तम्यर्थस्याभिहितत्वादन्तर्भूतत्वात् प्रथमैव कृता ॥ आम्रबुद्ध्या इति । तस्या अनन्तरमित्यर्थः ॥

(उद्द्योतः) न चेति । भूतपूर्वे हि स्थानशब्दो निवृत्तिवचनः स्यादिति भावः ॥ तत्पक्षे नित्यत्वं कथमिति पृच्छति—भाष्ये—कथमिति ॥ उत्तरमाह—बुद्ध्येति ॥ प्रतिपत्तृवशादिति । प्रतिपत्तृशब्देन तदीया प्रतिपत्तिर्लक्ष्यते, तद्वशात् प्रतिपत्तॄणां तथा ज्ञानव्यवहाराभ्यां बुद्धिधर्मारोपस्तत्रानुमीयते, स्वतस्तद्वत्त्वस्य तत्र बाधादिति भावः ॥ क्वचित्तु प्रतिपत्तिवशादिति पाठः ॥ तदाह—न त्विति । आरोपितभूतपूर्वत्वव्यवहाराच्च नित्यत्वहानिरिति भावः ॥ ननु 'प्राचीनं' इत्यस्यात्राधिकरणप्रतिपादकत्वात् सप्तमी स्यादत आह—प्राचीति । सप्तम्यन्ताद्दुस्पष्टात्सात्तेरञ्चेर्लुगिति लुक् ॥

भाष्ये—तस्य सर्वत्रेति । प्राग्देशवृक्षत्वावच्छिन्न इत्यर्थः ॥ स तत्र—न्यग्रोधेषु ॥ नन्वाम्रबुद्ध्या इति न तृतीया, अर्थासंङ्गतेः नापि षष्ठी, संबन्धिनोऽनुपस्थितेरत आह—तस्या अनन्तरमिति । अनन्तरपदाध्याहारेण षष्ठीति भावः ॥ केचित्तु 'आम्रबुद्ध्या' इत्यस्य 'तां विहाय' इत्यर्थं इत्याहुः ॥ भाष्ये-अपकृष्यमाणानिति । तत्र यथा बुद्धेरेवापकर्षं उपधानं च आम्रेषु न्यग्रोधेषु चारोप्यते, तथाऽत्रापि बुद्धिगतोत्पादविनाशयोः स्थान्यादेशभावस्य च शब्देष्वारोप इति भावः ॥ उपधानं-उत्पत्तिः ॥

(उत्सर्गकार्यनिराकरणम्)

(३१९ आक्षेपवार्तिकम् ॥ १ ॥)

॥*॥ अपवादप्रसङ्गस्तु स्थानिवत्त्वात् ॥*॥

(भाष्यम्)

अपवादे तु उत्सर्गकृतं च प्राप्नोति ॥ "कर्मण्यण्" "आतोऽनुपसर्गे कः" इति केऽपि अणि कृतं प्राप्नोति ॥

किं कारणम् ?

'स्थानिवत्त्वात् ॥

(प्रदीपः) अपवादप्रसङ्गस्त्विति । बुद्धिविपरिणाममात्रं यदि स्थान्यादेशभाव इति भावः ॥ 'कर्मण्यण्' इति सर्वत्राणुबुद्धिः प्रसक्ता 'आतोऽनुपसर्गे कः' इति कबुद्ध्या निवर्तते इति केऽप्यण्कृतप्रसङ्गः ॥

(उद्द्योतः) ननु उत्सर्गापवादयोः स्थान्यादेशभावाभावात् कथं स्थानिवत्त्वमत आह—बुद्धीति ॥ अण्कृतेति । ङीप् इत्यर्थः ॥

(आक्षेपबाधकभाष्यवार्तिकम्)

॥ उक्तं वा ॥

(भाष्यम्)

किमुक्तम् ?

*विषयेण तु नानालिङ्गकरणात् सिद्धम्*इति ॥

(प्रदीपः) विषयेण त्विति । तुशब्दः पुनरर्थे । यदयं गापोष्टगिति कापवादस्य टकः कित्त्वं शास्ति तज्ज्ञापयति—नोत्सर्गकृतमपवादे भवति-इति ॥

(उद्द्योतः) भाष्ये-उक्तं वेति वार्तिकस्यमुक्तमित्यंशं व्याचष्टे—विषयेण त्वित्यादि । अइउण्सूत्रे एकोऽकार इति पक्षे अनुबन्धसङ्करः प्राप्नोति केऽप्यण्कृतं प्राप्नोतीति पूर्वपक्षे विषयेण तु नानालिङ्गकरणात्सिद्धम्-इत्युक्तम् । विषयेऽण्कादौ भिन्नभिन्नलिङ्गकरणात् 'इह मुण्डो भव, इह जटी भव' इति लोकव्यवहारे यथा-यद्गुणको यत्रोच्यते तत्र तद्गुण एव भवति तथा-यल्लिङ्गो यत्रोच्यते तत्र तल्लिङ्गकार्यमेव नान्यानुबन्धकार्यमिति तदर्थश्चोक्तः ॥ एवं च सामान्यापेक्षत्वान्नियमस्य स्थानिवत्त्वप्रयुक्तस्यापि व्यावृत्तिरिति भावः ॥ वार्तिकेऽधिकरणस्यैव करणत्वविवक्षया तृतीया ॥ कैयटोक्तव्याख्याने तु अथवा यदयं श्यन्नादीनिति वक्ष्यमाणपक्षे एतत्पक्षाद्वैलक्षण्यं दुर्लभम् । शब्दमर्यादया वार्तिकात्तदर्थालाभश्च । तुशब्दस्य पुनरर्थत्वेऽपि नानापदानन्वयस्तदवस्थश्च । किंच कैयटोक्तार्थकं विषयेण तु पुनर्लिङ्गकरणात्सिद्धमिति भाष्ये तत्र पठितं, न त्वेवमिति दिक् ॥

(पक्षान्तरोपक्रमभाष्यम्)

॥ अथवा—

(३२० समाधानवार्तिकम् ॥ २ ॥)

॥ * ॥ सिद्धं तु षष्ठीनिर्दिष्टस्य स्थानिवद्वचनात् ॥ * ॥

(भाष्यम्)

सिद्धमेतत् ॥

कथम् ?

षष्ठीनिर्दिष्टस्यादेशः स्थानिवदिति वक्तव्यम् ॥

(प्रदीपः) षष्ठीनिर्दिष्टस्येति । न चापवादः षष्ठीनिर्दिष्टस्य स्थाने विधीयते ॥ नाभि नभं चेत्यादौ षष्ठ्याः स्थाने प्रथमाया विधानादस्ति षष्ठी ॥ विश्रवणरवणेति तु शब्दान्तरं प्रत्ययविषयं विज्ञेयम् । यथोक्तम्—*बालवायो विदूरं च प्रकृत्यन्तरमेव वा* इति । विश्रवःशब्दात्त्वनभिधानात् प्रत्ययाभावः ॥

(उद्द्योतः) तत्रत्यं वेत्यंशं व्याचष्टे—अथवा सिद्धं त्विति ॥ अनुवर्तमानं षष्ठीतिपदं षष्ठीनिर्दिष्टलाक्षणिकं षष्ठ्या विपरिणम्यत इत्याशयेनाह—षष्ठीनिर्दिष्टस्येति ॥ नन्वेवं नाभि नभमित्यादौ षष्ठीनिर्देशाभावात्स्थानिवत्त्वाभावेन यत्प्रत्ययसंनियुक्तनभस्य भत्वाङ्गत्वयोरभावाद्यस्येति लोपो न स्यादत आह—नाभीति । विधानात्-करणात् ॥ यत्र तर्हि स्थान्यनुमानं तत्र कथमत आह—विश्रवणेति । प्रत्ययविषयम्-शिवाद्यण्विषयम् ॥ बालवेति । वैदूर्यस्य विदूरान्न प्रभवः किंतु बालवायात्-इति विदूराञ्ञ्य इत्यस्यासङ्गतौ इदं वार्तिकम् । बाल्वायो विदूरमापद्यते, अथास्मात्प्रत्ययः । यद्वा बाल्वायार्थवाचको विदूरोऽन्य एव प्रत्ययविषय इति तदर्थः ॥ ननु विश्रवणादेरनादेशत्वे विश्रवःशब्दादपि प्रत्ययः स्यादत आह—विश्रव इति ॥

(आक्षेपभाष्यम्)

तर्हि षष्ठीनिर्दिष्टग्रहणं कर्तव्यम् ॥

(समाधानभाष्यम्)

न कर्तव्यम् । प्रकृतमनुवर्तते ॥

क प्रकृतम् ?

"षष्ठी स्थानेयोगा" इति ॥

(समाधानान्तरभाष्यम्)

अथवा—आचार्यप्रवृत्तिर्ज्ञापयति—नापवादे उत्सर्गकृतं भवतीति । यदयं श्यन्नादीन् कांश्चिच्छितः करोति-श्यन्, श्नम्, श्ना, शः, श्नुरिति ॥

(प्रदीपः) यदयमिति । न च पित्त्वनिवृत्त्यर्थ नियमार्थं शित्त्वम् । श्यनो नित्त्वात् ज्ञापकात् पित्त्वनिवृत्तेः सिद्धत्वात् ॥ न ह्यत्र पित्त्वस्य नित्त्वस्य वा विशेषोऽस्तीति केचिदाहुः ॥

तद्युक्तम्। ताच्छील्यादौ विषये चानँशि नित्त्वं प्रकृतेराद्युदात्तार्थं स्यात्। तस्मादिष्टसिद्धये सामान्येन ज्ञापकं शित्त्वमाश्रीयते—अपवादे उत्सर्गकृतं न भवतीति ॥

(उद्द्योतः) विशेषोऽस्तीति। नित्त्वं हि प्रत्ययाद्युदात्तत्वबाधेनाद्युदात्तत्वाय। स्थानिवत्त्वात्पित्वेनानुदात्तत्वे तु लसार्वधातुकस्याप्युपदेशादित्यनुदात्तत्वे धातोरुदात्तत्वं सिद्धमेवेति भावः ॥ आद्युदात्तार्थमिति। इदमपि नित्त्वप्रयुक्तान्तोदात्तत्वं बाधित्वेत्यर्थः ॥ 'अन्यत्र विकरणेभ्यः' इत्यपि नित्त्वसामर्थ्याल्लभ्यत इति भावः ॥ किंच वावृतु इत्यस्यानेकाचो दिवादौ सत्त्वेन तत्रापि नित्त्वपित्त्वयोर्विशेषः ॥ कैयटस्वरसस्तु तस्य धातोर्दिवादावभाव एवेति बोध्यम् ॥ इष्टसिद्धये इति। वैयर्थ्यान्नियमत्वं वा ज्ञापकत्वं वेत्यत्र विनिगमकाभावान्नित्त्वसामर्थ्यादन्यत्र विकरणेभ्य इत्युपदेशबाधकल्पनाऽपेक्षया स्थानिवदित्यतिदेशबाधकल्पनस्यैवौचित्याच्चेति भावः ॥ सामान्येनेति। न विकरणविषयमेव, नापि पित्त्वविषयमेवेत्यर्थः ॥ भाष्ये-श्यन्नादीनिति। उत्सर्गसजातीयानुबन्धवदपवादानामुपलक्षणम् ॥

(स्थानिवत्त्वप्रासदूषणनिराकरणम्)

(३२१ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ तस्य दोषस्तयादेश उभयप्रतिषेधः ॥ * ॥

(भाष्यम्)

तस्यैतस्य लक्षणस्य दोषः-तयादेश उभयप्रतिषेधो वक्तव्यः। उभये देवमनुष्याः। तयपो ग्रहणेन ग्रहणाद् जसि विभाषा प्राप्नोति ॥

(आक्षेपनिराकरणसिद्धान्तिभाष्यम्)

नैष दोषः। अयच् प्रत्ययान्तरम् ॥

(आक्षेपसाधकभाष्यम्)

यदि प्रत्ययान्तरम्, उभयीति ईकारो न प्राप्नोति ॥

(आक्षेपबाधकभाष्यम्)

मा भूदेवम्। मात्रच्-इत्येवं भविष्यति ॥
कथम्?
मात्रजिति नेदं प्रत्ययग्रहणम् ॥
किं तर्हि?
प्रत्याहारग्रहणम् ॥
क सन्निविष्टानां प्रत्याहारः?
मात्रशब्दात्प्रभृति आ अयचश्चकारात् ॥

(आक्षेपसाधकभाष्यम्)

यदि प्रत्याहारग्रहणम्, 'कति तिष्ठन्ति' अत्रापि प्राप्नोति ॥

(प्रदीपः) कति तिष्ठन्तीति। परिहारान्तरसद्भावात् न षट्स्वस्रादिभ्य इति प्रतिषेधो नोक्तः ॥

(आक्षेपबाधकभाष्यम्)

अत इति वर्तते ॥

(आक्षेपसाधकभाष्यम्)

एवमपि 'तैलमात्रा-घृतमात्रा' अत्रापि प्राप्नोति ॥

(प्रदीपः) तैलमात्रेति। चकारस्य प्रत्याहारार्थस्योपादानात्तस्याऽविशेषत्वान्मात्रशब्दमात्रग्रहणप्रसङ्गः ॥

(आक्षेपबाधकभाष्यम्)

सदृशस्याप्यसंनिविष्टस्य न भवति प्रत्याहारग्रहणेन ग्रहणम् ॥

(प्रदीपः) सदृशस्येति। प्रत्ययानुकरणं मात्रशब्द इति प्रातिपदिकस्याग्रहणमित्यर्थः ॥

(उद्द्योतः) प्रत्ययानुकरणमिति। टिड्ढाणञ्सूत्रे पाठचर्यादिति भावः ॥

(३२२ आक्षेपवार्तिकम् ॥ २ ॥)

॥ * ॥ जात्याख्यायां वचनादेशे स्थानिवद्भावप्रतिषेधः ॥ * ॥

(भाष्यम्)

जात्याख्यायां वचनादेशे स्थानिवद्भावस्य प्रतिषेधो वक्तव्यः। व्रीहिभ्य आगत इत्यत्र "घेर्ङिति" इति गुणः प्राप्नोति ॥

(प्रदीपः) जात्याख्यायामिति। एकस्मिन् यत् प्राप्तमेकवचनं तस्य प्रसङ्गे बहुवचनमादेश इति कल्पनाऽऽश्रयेण दोषोपन्यासः ॥

(उद्द्योतः) ननु 'एकस्मिन् बहुवचनं' इत्युक्त्या षष्ठ्यभावात्कथमादेशत्वमत आह—एकस्मिन्निति ॥

(आक्षेपनिरासभाष्यम्)

नैष दोषः। उक्तमेतत्- * अर्थातिदेशात्सिद्धम् * इति ॥

(उद्द्योतः) भाष्ये—अर्थातीति। बहुवचनशब्दो न प्रसयपरः, किं त्वर्थपर इति भावः ॥

(३२३ आक्षेपवार्तिकम् ॥ ३ ॥)

॥ * ॥ ङ्याब्ग्रहणेऽदीर्घः ॥ * ॥

(भाष्यम्)

ङ्याब्ग्रहणेऽदीर्घ आदेशो न स्थानिवदिति वक्तव्यम् ॥
किंप्रयोजनम्?
निष्कौशाम्बिः। अतिखट्वः। ङ्याब्ग्रहणेन ग्रहणात्सुलोपो मा भूदिति ॥

(उद्योतः) ङ्याब्ग्रहणे अदीर्घ इति–भाष्ये । ननु गङ्गाया इः–गङ्गिः, गङ्गीयतेः क्विपि–गङ्गीरित्यादौ स्थानिवत्त्वनिषेधो न स्यात् । न च तत्र स्थानिवत्त्वे इष्टापत्तिरस्तु सुलोपश्चास्तु इति वाच्यम् । आकारेकारप्रश्लेषमादायैतत्प्रत्याख्यानपरभाष्यविरोधात् । सूत्रमतेऽपि नात्र लोपः, प्रत्यासत्त्या ङ्याप्पदोपस्थित-ईकाराकारयोरेव दीर्घग्रहणेन ग्रहणादिति चेन्न । तेषाम्[३]अनभिधानात् । न चेदं विशेषणं व्यर्थम्, 'खट्वा' इत्यादौ सवर्णदीर्घे परत्वेन परादिवद्भावप्राप्त्या स्थानिवत्त्वस्यैवाभावादिति वाच्यम् । न स्थानिवदित्यस्य स्थानिकार्यं न लभते–इत्यर्थे येन केनापि प्राप्तस्य स्थानिकार्यस्य निषेध इति दीर्घेऽप्याप्त्वप्रयुक्तकार्याभावशङ्कावारणार्थं तत् ॥ 'ह्रस्वः' इति नोक्तम्, चित्रायां जातश्चित्र इत्यादौ जातार्थलुकि टापो लुक्यपि प्रत्ययलक्षणेन हल्ङ्यादिलोपापत्तेः ॥ मम तु लुकोऽपि दीर्घभिन्नत्वात्तत्रापि न स्थानिप्रयुक्तकार्यातिदेश इति दिक् ॥ [६]अतिखट्व इति । न चात्र ह्रस्व आकारस्येति तद्गतमात्वमल्विधिरिति वाच्यम् । गोस्त्रियोरित्यस्य स्त्रीप्रत्ययान्तान्तप्रातिपदिकान्तस्य ह्रस्व इत्यर्थः । अचश्चेति तु नोपतिष्ठते, अनियमाप्रसक्तेः । स्त्रीप्रत्ययत्वं च टाङीत्यादिविशिष्टनिष्ठमिति न दोषः । सूत्रोपात्तस्यैव स्थानितावच्छेदकत्वमित्युक्तम् । अत एव गोटाङ्ग्रहणं कर्तव्यमिति वार्तिककृतोक्तम् । स्वरितत्ववलात् स्त्रियामिति प्रकृत्य ये विहितास्तेषां ग्रहणमिति भाष्यकृतोक्तम् । विधानं चानुबन्धविशिष्टस्यैवेति स्पष्टमेवेति दिक् ॥

(आक्षेपबाधकभाष्यम्)

नतु च दीर्घादित्युच्यते ॥

(आक्षेपसाधकलाघवभाष्यम्)

तत्र वक्तव्यं भवति ॥

(तटस्थाक्षेपभाष्यम्)

किं पुनरत्र ज्यायः ?

(तटस्थाक्षेपसमाधानभाष्यम्)

स्थानिवत्त्वप्रतिषेध एव ज्यायान् । इदमपि सिद्धं भवति—अतिखट्वाय, अतिमालाय । "याडापः" इति याड् न भवति ॥

(उद्योतः) अतिखट्वायेति । न च आबन्तादङ्गात्परस्य याडिति तदर्थः, उपसर्जनस्त्रीप्रत्यये च तदादिनियमात् नैतदङ्गमाबन्तमिति स्थानिवत्त्वेऽपि न याट्प्रवृत्तिरिति वाच्यम् । प्रत्ययग्रहणपरिभाषयाऽऽबन्तग्रहणे तेन चाङ्गविशेषणे 'आबन्तान्तं यदङ्गं' इत्यर्थान्न दोषः । अत एवार्थखट्वायामित्यादौ याड्सिद्धिरिति भावः ॥

(आक्षेपभाष्यम्)

अथेदानीमसत्यपि स्थानिवद्भावे दीर्घत्वे कृते पिञ्चासौ भूतपूर्व इति कृत्वा "याडापः" इति याट् कस्मान्न भवति ?

(प्रदीपः) भूतपूर्व इति । अनुबन्धकार्ये सर्वत्र भूतपूर्वगत्याश्रयणात् । 'आ' इति च रूपसद्भावात् ॥

(समाधानभाष्यम्)

लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैवेति ॥

(प्रदीपः) लक्षणेति । अत्र चान्तरा ह्रस्वे कृते स एवायमिति बुद्धिविच्छेदः ॥

(उद्योतः) नन्वेवमपि दीर्घे कृते स्थानिवद्भावेनाप्त्वं स्यादेव, अयं निषेधस्तु न, दीर्घत्वात् । अत आह—अत्र चेति । एवं च स्थानिवद्भावेन तदलाभः, तत्स्थानिन्येतत्त्वादिति भावः ॥

(आक्षेपभाष्यम्)

ननु चेदानीं सत्यपि स्थानिवद्भावे एतया परिभाषया शक्यमिहोपस्थातुम् ॥

(उद्योतः) भाष्ये–ननु चेदानीमिति । वार्तिकाकरणे–इत्यर्थः ॥ सत्यपीति । निष्कौशाम्बिरित्यादौ ॥

(समाधानभाष्यम्)

नेत्याह । न तर्हीदानीं क्वचिदपि स्थानिवद्भावः स्यात् ॥

(तृतीयाक्षेपभाष्यम्)

तत्तर्हि वक्तव्यम् ॥

न वक्तव्यम् ॥

(समाधानभाष्यवार्तिकम्)

॥ प्रश्लिष्टनिर्देशात्सिद्धम् ॥

(भाष्यम्)

प्रश्लिष्टनिर्देशोऽयम्—ङी ई ईकारान्तात्, आ आप् आकारान्तादिति ॥

(उद्योतः) प्रश्लिष्टनिर्देशादिति । अतिखट्वायेत्यादौ आकारस्य लाक्षणिकत्वादेव न दोषः । 'खट्वायै' इत्यादौ तु न दोषो यतो लक्षणप्रवृत्तिं विना यद्रूपासंभवस्तदेव लाक्षणिकं परिभाषया निषेधविषयः । न चेदं तथा । एकादेशतः प्रागपि तद्रूपसत्त्वादित्याहुः ॥ अयं च प्रश्लेषो 'याडापः' 'आङिः चापः' 'औङ आपः' 'ङेराम्नद्याप्' 'हल्ङ्याब्' इत्येतेषु ॥ ह्रस्वनद्याप इत्यत्र प्रश्लेषे न मानमिति दिक्[१] ॥ ननु भाष्यमते सूत्रमते च 'अतिखट्वस्य अः–अतिखट्वा' इत्यत्र सुलोपो भवति । वार्तिकमते तु न, अतिखट्वे आबन्तत्वस्य विच्छेदादग्रे प्ररोहासंभवादिति चेन्न । अनभिधानेनैषां प्रयोगाणामभावात् । यद्वा[१३] स्थानिवद्भावस्य कार्यार्थत्वेनातिखट्वशब्दे आकारप्रश्लेषे फलाभावात्तदप्रवृत्तौ स्थानिन्याप्त्वबुद्धेरभावात्तदादेशे तदारोहः सूत्रमते भाष्यमते च दुर्लभः, परम्परया कार्यमादायाचस्थानिवत्त्वप्रवृत्तौ मानाभावात् ॥ यत्तु वार्तिकमते लोपाप्राप्त्या भाष्यादिमतेऽपि ईकारादिप्रश्लेषान्तरेण लोपाभाव एव वाच्यः । एकप्रश्लेषेणैवातिखट्व्यावृत्तौ सिद्धायां दीर्घग्रहणं सूत्रमते, भाष्यमते तत्प्रत्याख्यानाय कृतप्रश्लेषान्तरं च नियमार्थम्–न कदाचिद् रूपान्तरं प्राप्तौ यौ ङ्यापाविति, एवं च न दोष इति ॥ तन्न । मानाभावात् । [१६]अतिखट्वायेत्येव वार्तिकप्रयोजनं प्रदर्श्याकारप्रश्लेषेण तत्प्रत्याख्यातम्[१७] ॥

(३२४ आक्षेपवार्तिकम् ॥ ४ ॥)

॥ * ॥ आहिभुवोरीट्प्रतिषेधः ॥ * ॥

(भाष्यम्)

आहिभुवोरीट्प्रतिषेधो वक्तव्यः । आत्थ, अभूत् । अस्तिब्रूग्रहणे ग्रहणादीट् प्राप्नोति ॥

(उद्योतः) भाष्ये—आहिभुवोरिति । 'भुव ईट्' 'अस्तिसिचोऽपृक्ते' इत्याभ्यां प्राप्तः ॥

(आह्रंशे आक्षेपनिराकरणभाष्यम्)

आहेस्तावन्न वक्तव्यः । आचार्यप्रवृत्तिर्ज्ञापयति—नाहेरीड् भवतीति । यदयम्—"आहस्थः" इति झलादिप्रकरणे थत्वं शास्ति ॥

(ज्ञापकबाधकभाष्यम्)

नैतदस्ति ज्ञापकम् । अस्ति ह्यन्यदेतस्य वचने प्रयोजनम् ॥

किम् ?

भूतपूर्वगतिर्यथा विज्ञायेत । झलादिर्यो भूतपूर्व इति ॥

(प्रदीपः) झलादिरिति । णलादिषु थलेव भूतपूर्वो झलादिरिति भावः ॥

(ज्ञापकसमाधानभाष्यम्)

यद्येवं थवचनमनर्थकं स्यात् । आथिमेवायमुच्चारयेत्—"ब्रुवः पञ्चानामादित आथो ब्रुवः" इति ॥

(प्रदीपः) आथिमिति । तिबादयो हि सर्वे झलादय इति णलादयो भूतपूर्वा झलादय इति भावः ॥

(भ्वंशेऽप्याक्षेपनिराकरणभाष्यम्)

भवतेश्चापि न वक्तव्यः । "अस्तिसिचोऽपृक्ते" इति द्विसकारको निर्देशः । अस्तेः सकारान्तादिति ॥

(उद्योतः) द्विसकारको निर्देश इति । अस्तिस्सिच इति सूत्रपाठ इति भावः ॥ प्रकारान्तरे तु आदेशेरपहारात् सद्वयोच्चारणाभावेन 'निर्देशः' इति भाष्यास्वारस्यम् । अत एव वार्तिककृता सिज्लुकः स्थानिवत्त्वस्य प्रत्ययलक्षणस्य वा प्रतिषेधो नारब्धः सकारस्य सिज्विशेषणत्वमित्याशयेन । तद्विशेषणं सामर्थ्यात् श्रूयमाणसान्तपरमिति प्रत्ययलक्षणसूत्रस्य विप्रकर्षेऽपि न दोषः । भाष्यकृता तु मध्यमणिन्यायेनोभयसंबन्धमङ्गीकृत्य भुवः स्थानिवत्त्वप्रतिषेधोऽपि प्रत्याख्यात इति बोध्यम् ॥

(३२५ आक्षेपवार्तिकम् ॥ ५ ॥)

॥ * ॥ वध्यादेशे वृद्धितत्त्वप्रतिषेधः ॥ * ॥

(भाष्यम्)

वध्यादेशे वृद्धितत्त्वयोः प्रतिषेधो वक्तव्यः । वधकं पुष्करमिति । स्थानिवद्भावाद् वृद्धितत्त्वे प्राप्नुतः ॥

(आक्षेपनिराकरणभाष्यम्)

नैष दोषः । उक्तमेतत्—'नायं ण्वुल्, किंतु अन्योऽयमकशब्दः किदौणादिको रुचक इति यथा' ॥

(उद्योतः) नायं ण्वुलिति । यद्यपि वृद्धिर्वधस्यादन्तत्वेनापि वारयितुं शक्या, तथापि तत्त्वांशप्रत्याख्यानायेदमावश्यकमिति भावः ॥

(३२६ आक्षेपवार्तिकम् ॥ ६ ॥)

॥ * ॥ इड्विधिश्च ॥ * ॥

(भाष्यम्)

इड्विधेयः । आवधिषीष्ट । "एकाच उपदेशेऽनुदात्तात्" इति प्रतिषेधः प्राप्नोति ॥

(उद्योतः) इड्विधिश्चेति । यथेड्विधिः सिध्यति तथा तन्निषेधे स्थानिवत्त्वप्रतिषेधो वक्तव्य इत्यर्थः । इड्विधेय इत्यस्य तन्निषेधे स्थानिवत्त्वप्रतिषेधद्वारेति शेषः ॥ आवधिषीष्टेति । आङो यमहन इत्यात्मनेपदम् ॥ प्रतिषेधः प्राप्नोतीति । तत्र वधेः स्थानिवत्त्वेनाक्तया निषेधः प्राप्त इण्निषेधरूपे कार्ये स्थानिवत्त्वप्रतिषेधेनाक्त्वाभावाश्चेत्यर्थः ॥ वधेरपि सूत्रे स्थान्यनुरूपानुदात्तस्यैवोच्चारणेन अनुदात्तत्वं बोध्यम् ॥

(आक्षेपनिराकरणभाष्यम्)

नैष दोषः । आद्युदात्तनिपातनं करिष्यते । स निपातनस्वरः प्रकृतिस्वरस्य बाधको भविष्यति ॥

(उद्योतः) प्रकृतिस्वरस्य—प्रकृतितः स्थान्यनुरूपतया प्राप्तस्यानुदात्तत्वस्य ॥

(प्रत्याक्षेपभाष्यम्)

एवमप्युपदेशिवद्भावो वक्तव्यः । यथैव हि निपातनस्वरः प्रकृतिस्वरं बाधते, एवं प्रत्ययस्वरमपि बाधेत—आवधिषीष्ट-इति ॥

(प्रदीपः) आवधिषीष्टेति । यदा यच्छब्दप्रयोगः—'यदावधिषीष्ट' इति तिङ्ङतिङ इति निघातः प्राप्तो निपातैर्यद्यदीति प्रतिषिद्धः, तदैतदुदाहरणम् । क्वचित्तु 'यदावधिषीष्ट' इति पाठः ॥

(उद्योतः) प्रत्ययस्वरं—तत्प्रयुक्तनिघातम् ॥ नन्वत्रोदाहरणे तिङ्ङतिङ इति निघातेन भाष्यमत आह—यदा यदिति । 'यदा' इत्यस्य 'तदैतदुदाहरणं' इत्यनेनान्वयः ॥ मध्ये भवति तदेत्पाठः ॥

(आक्षेपपरिहारभाष्यम्)

नैष दोषः । आर्धधातुकीयाः सामान्येन भवन्ति, अनवस्थितेषु प्रत्ययेषु । तत्रार्धधातुकसामान्ये वधिभावे कृते, सति शिष्टत्वात् प्रत्ययस्वरो भविष्यति ॥

(उद्योतः) भाष्ये–आर्धधातुकसामान्ये इति । 'आर्धधातुके' इतिवल्लिङ्गीत्याद्यपि विषयसप्तम्येवेति भावः ॥ एवं चाद्युदात्तनिपातने उपदेशिवद्भावारम्भगौरवाभावेन उपदेशत्वावच्छेदेनानुदात्तत्वाभावात् स्थानिवद्भावेनाक्त्वे सत्यपि निषेधाप्राप्त्या तन्निषेधो न कार्य इति तात्पर्यम् ॥

(३२७ आक्षेपवार्तिकम् ॥ ७ ॥)

॥ * ॥ आकारान्तान्नुक्पुक्प्रतिषेधः ॥ * ॥

(भाष्यम्)

आकारान्तान्नुक्पुकोः प्रतिषेधो वक्तव्यः । विलापयति । भापयते । लीभीग्रहणेन ग्रहणान्नुक्पुकौ प्राप्नुतः ॥

(उद्योतः) आकारान्तादिति । विभाषा लीयतेः- बिभेतेर्हेतुभये इत्यात्वम् । लीलोर्नुग्लुकाविति भियो हेतुभये इति च नुक्पुकौ ॥

(आक्षेपपरिहारभाष्यवार्तिकम्)

॥ लीभियोः प्रश्लिष्टनिर्देशात्सिद्धम् ॥

(भाष्यम्)

लीभियोः प्रश्लिष्टनिर्देशोऽयम्—ली ई ईकारान्तस्य, भी ई ईकारान्तस्य चेति ॥

(उद्योतः) प्रश्लिष्टनिर्देशादिति । यद्यपि भिय इत्यत्र प्रश्लेषे एकादेशस्य कृदतिङ्सूत्रभाष्योक्तरीत्या पूर्वधर्मावच्छिन्नोद्देश्यके इयङ्विधौ अचः परस्मिन्निति स्थानिवत्त्वेनेयङ् दुर्लभः, तथापि सौत्रत्वात्स इति बोध्यम् । 'क्षियो निष्ठायाम्' इति दीर्घविधाविवेति दिक् ॥

(३२८ आक्षेपवार्तिकम् ॥ ८ ॥)

॥ * ॥ लोडादेशे शाभावजभावधित्वहिलोपैत्त्वप्रतिषेधः ॥ * ॥

(भाष्यम्)

लोडादेशे एषां प्रतिषेधो वक्तव्यः ॥ शिष्टात् । हतात् । भिन्तात् । कुरुतात् । स्तात् । लोडादेशे कृते शाभावो जभावो धित्वं हिलोप एत्त्वमित्येते विधयः प्राप्नुवन्ति ॥

(उद्योतः) शाभावेत्यादि । शा हौ, हन्तेर्जः, हुझल्भ्यो हेर्धिः, उतश्च प्रत्ययाद्, घ्वसोरेद्धावित्येतैः [२] ॥

(आक्षेपपरिहारभाष्यम्)

नैष दोषः । इदमिह संप्रधार्यम्—लोडादेशः क्रियताम्, एते विधय इति । किमत्र कर्तव्यम्? परत्वाल्लोडादेशः ॥

(उद्योतः) परत्वादिति । युगपत्प्रवृत्तौ स्वस्वनिमित्तानन्तर्याभावरूपासंभवस्य सत्त्वात् । तादृशासंभव एव च विप्रतिषेधशास्त्रप्रवृत्त्युपयोगी । स्थानिवद्भावस्तु कार्यप्रवृत्त्युत्तरम्, न प्रवृत्तिकाले इति युगपदसंभवः स्पष्ट एवेति भावः ॥ एवमग्रेऽपि ॥

(आक्षेपभाष्यम्)

अथेदानीं लोडादेशे कृते पुनःप्रसङ्गविज्ञानात् कस्मादेते विधयो न भवन्ति?

(आक्षेपबाधकभाष्यम्)

"सकृद्गतौ विप्रतिषेधे यद्बाधितं तद्बाधितमेव" इति कृत्वा ॥

(३२९ आक्षेपवार्तिकम् ॥ ९ ॥)

॥ * ॥ त्रयादेशे स्रन्तप्रतिषेधः ॥ * ॥

(भाष्यम्)

त्रयादेशे स्रन्तस्य प्रतिषेधो वक्तव्यः । तिसृणाम् । तिसृभावे कृते "त्रेस्त्रयः" इति त्रयादेशः प्राप्नोति ॥

(आक्षेपनिराकरणभाष्यम्)

नैष दोषः । इदमिह संप्रधार्यम्-तिसृभावः क्रियताम्, त्रयादेश इति । किमत्र कर्तव्यम्? परत्वात्तिसृभावः ॥

(उद्योतः) परत्वात्तिसृभाव इति । न च लिङ्गविशेषविभक्तिसंज्ञापेक्षितिस्रपेक्षया प्रत्ययविशेषापेक्षस्यात्यन्तरङ्गत्वात्त्रयादेशापत्तिः । किंच स्वरूपेणोपादाने विशेषापेक्षत्वकृतबहिरङ्गत्वं नेत्यर्थस्य पादःपदिति सूत्रे भाष्ये ध्वनितत्वेन सर्वथा त्रयादेशस्यान्तरङ्गत्वमिति वाच्यम् अर्थसंज्ञाकृतबहिरङ्गत्वस्य शास्त्रेऽनाश्रयणात् । एतेन चतस्र इत्यपि व्याख्यातमिति दिक् ॥

(आक्षेपभाष्यम्)

अथेदानीं तिसृभावे कृते पुनःप्रसङ्गविज्ञानात् त्रयादेशः कस्मान्न भवति?

(समाधानभाष्यम्)

सकृद्गतौ विप्रतिषेधे यद्बाधितं तद्बाधितमेवेति ॥

(३३० आक्षेपवार्तिकम् ॥ १० ॥)

॥ * ॥ आम्विधौ च ॥ * ॥

(भाष्यम्)

आम्विधौ च स्रन्तस्य प्रतिषेधो वक्तव्यः । चतस्रस्तिष्ठन्ति । चतसृभावे कृते "चतुरनडुहोरामुदात्तः" इत्याम् प्राप्नोति ॥

(आक्षेपनिराकरणभाष्यम्)

नैष दोषः । इदमिह संप्रधार्यम्—चतसृभावः क्रियताम्, "चतुरनडुहोरामुदात्तः" इत्यामिति । किमत्र कर्तव्यम्? परत्वाच्चतसृभावः ॥

(आक्षेपभाष्यम्)

अथेदानीं चतसृभावे कृते पुनःप्रसङ्गविज्ञानाद् आम् कस्मान्न भवति?

(समाधानभाष्यम्)

सकृद्गतौ विप्रतिषेधे यद्बाधितं तद्बाधितमेवेति ॥

(३३१ आक्षेपवार्तिकम् ॥ ११ ॥)

॥ * ॥ स्वरे च वस्वादेशे ॥ * ॥

(भाष्यम्)

स्वरे च वस्वादेशे प्रतिषेधो वक्तव्यः । विदुषः पश्य । "शतुरनुमो नद्यजादी" 'अन्तोदात्तात्' इत्येष स्वरः प्राप्नोति ॥

(उद्योतः) विदुष इत्यत्र विदेः शतुर्वसुरिति शत्रादेशो वसुः ॥ शतुरनुम इत्यादि । अनुमः शता तदन्तात्परा नदी अजादिश्च शसादिर्विभक्तिरुदात्तेत्यर्थः ॥

(आक्षेपनिराकरणभाष्यम्)

नैष दोषः। 'अनुमः' इति प्रतिषेधो भविष्यति॥

(अनुपपत्तिभाष्यम्)

अनुम इत्युच्यते, न चात्र नुमं पश्यामः॥

(अनुपपत्तिपरिहारभाष्यम्)

अनुम इति नेदमागमग्रहणम्॥

किं तर्हि?

प्रत्याहारग्रहणम्॥

क सन्निविष्टानां प्रत्याहारः?

उकारात्प्रभृत्या नुमो मकारात्॥

(प्रदीपः) उकारात् प्रभृतीति। तनादिकृञ्भ्य उरित्यतः। तत्र च वसुरन्तर्भूतः॥

(अनिष्टापत्तिभाष्यम्)

यदि प्रत्याहारग्रहणं 'लुनता-पुनता' अत्रापि प्राप्नोति॥

(प्रदीपः) यदीति। श्नाप्रत्ययस्य प्रत्याहारेऽन्तर्भावात्॥

(उद्योतः) (भाष्ये) यदि प्रत्याहारेति। उम्‌रहितशत्रन्तेत्यर्थ इत्यभिमानः॥

(अनिष्टापत्तिवारणभाष्यम्)

अनुम्ग्रहणेन न शत्रन्तं विशेष्यते॥

किं तर्हि?

शतैव विशेष्यते—शता योऽनुम्क इति॥

अवश्यं चैतदेवं विज्ञेयम्। आगमग्रहणे हि सतीह प्रसज्येत—मुञ्चता, मुञ्चतः—इति॥

(प्रदीपः) शता य इति। न चात्र श्ना शतुः कृत इत्यनुमेव शता॥ मुञ्चतेति। शत्रन्तस्य सनुम्कत्वादिति भावः॥ तस्मादागमग्रहणेऽपि शतैव विशेषणीय इति प्रत्याहारग्रहणेऽपि स एव विशेष्यत इत्यदोषः॥

(उद्योतः) (भाष्ये) अनुम्क इति। वसोरपि व्यपदेशिवद्भावेनोम्स्त्वम्॥ आगमग्रहणे हीति। हिरप्यर्थे। तद्ग्रहणेऽपीत्यर्थः॥ कैयटे—अनुमेव शतेति। यद्यपि शताऽपि प्रत्याहारान्तर्गतः, तथापि सामर्थ्यात्तद्भिन्नस्यैव प्रत्याहारान्तर्गतस्य ग्रहणमिति भावः॥ व्यापकत्वात्प्राथम्याच्च तनादेरुकारेण प्रत्याहार इति तात्पर्यम्॥

(३३२ आक्षेपवार्तिकम्॥ १२॥)

॥ * ॥ गोः पूर्वणित्वात्वस्वरेषु ॥ * ॥

(भाष्यम्)

गोः पूर्वणित्वात्वस्वरेषु प्रतिषेधो वक्तव्यः। चित्रग्वग्रं, शबलग्वग्रम्। "सर्वत्र विभाषा गोः" इति विभाषा पूर्वत्वं प्राप्नोति॥

(प्रदीपः) सर्वत्रेति। प्रकृतिभावोऽनेन विधीयते, न तु पूर्वत्वम्। तस्मादेङः पदान्तादतीति पूर्वत्वं प्राप्नोतीति भाष्यम्॥ यदा त्वप्रकृतिभावः, तदाऽयं प्रसङ्ग उक्तः॥ उत्तरं त्वल्विधित्वात्स्थानिवत्त्वाभावः॥ ५६॥

(उद्योतः) भाष्ये—विभाषा पूर्वत्वं प्राप्नोतीति। अत्र वार्तिके भाष्ये च पूर्वशब्देन तदपवादो लक्ष्यते॥ भाष्ये—सर्वत्रेति चावच्छितिसूत्रस्याप्युपलक्षणम्। ध्वनितं चेदमवङ्सूत्रे भाष्ये—इति षष्ठे निरूपयिष्यामः॥ अनन्तरस्येति न्यायेन तदपवादोऽपि परत्वाण्णमपि बाधित्वा स्यादित्याशयः॥ यत्तु कैयटेन—तस्मादेङ इत्यादि प्रसङ्ग उक्त इत्यन्तमुक्तम्, तत्तु चिन्त्यमेव। एङः पदान्तादिति सूत्रे पदपदोच्चारणसत्त्वेन शङ्काया असंभवदुक्तिकत्वात्। भाष्योक्ते तु पदपदाभावादनुवृत्तिमजानतः शङ्केत्युक्तिसंभवात्॥

(दूषणप्रथमाक्षेपनिराकरणभाष्यम्)

नैष दोषः। एङ इति वर्तते। तत्रानल्विधाविति प्रतिषेधो भविष्यति॥

(समाधाननिरासभाष्यम्)

एवमपि 'हे चित्रगोऽग्रम्' अत्र प्राप्नोति॥

(उद्योतः) भाष्ये—एवमपीति। लाक्षणिकत्वादस्य गोशब्दस्य स्वतः प्रकृतिभावाप्राप्तावपि स्थानिवत्त्वेन प्राप्नोतीति तत्प्रतिषेधो वक्तव्य इत्यर्थः॥ यदि तु ओत्सूत्रभाष्योक्तरीत्या वर्णग्रहणेऽपि प्रतिपदोक्तपरिभाषा प्रवर्तते, तदेदं वचनं न कार्यम्। एङो लाक्षणिकत्वात्। तदंशे स्थानिवत्त्वानपेक्षणेनातिदेशविषये तदप्रवृत्तिरित्यपि नेत्याहुः॥

(द्वितीयतृतीयाक्षेपभाष्यम्)

णित्वम्। चित्रगुः, चित्रगू, चित्रगवः। "गोतो णित्" इति णित्वं प्राप्नोति॥

आत्वम्। चित्रगुं पश्य, शबलगुं पश्य। "औतः—" इत्यात्वं प्राप्नोति॥

नैष दोषः॥

(द्वितीयतृतीयाक्षेपवारणभाष्यवार्तिकम्॥)

॥ तपरकरणात्सिद्धम् ॥

(भाष्यम्)

तपरकरणसामर्थ्यात् णित्वात्वे न भविष्यतः॥

(उद्योतः) भाष्ये—तपरकरणसामर्थ्यादिति। एवं च गत्याविवक्षितत्वेनाल्विधित्वात्स्थानिवत्त्वाभाव इति भावः॥ ५९॥

(आक्षेपभाष्यम्)

स्वर। बहुगुमान्। "न गोश्वन्साववर्ण—" इति प्रतिषेधः प्राप्नोति॥

(३३३ आक्षेपवार्तिकम्॥ १३॥)

॥ * ॥ करोतिपिबत्योः प्रतिषेधः ॥ * ॥

(भाष्यम्)

करोतिपिबत्योः प्रतिषेधो वक्तव्यः। कुरु-पिबेति। स्थानिवद्भावाल्लघूपधगुणः प्राप्नोति॥

(आक्षेपनिराकरणे भाष्यवार्तिकम्)

॥ उक्तं वा ॥

(भाष्यम्)

किमुक्तम् ?

"करोतौ तपरकरणनिर्देशात्सिद्धम्" ॥ "पिविरदन्तः" इति ॥

स्थानिवदादेशोऽनल्विधौ ॥ ५६ ॥

(५२ अतिदेशसूत्रम् ॥ १ । १ । ८ आ. २ ॥)

अचः परस्मिन् पूर्वविधौ ॥ १।१।५७ ॥

(प्रदीपः) अचः परस्मिन्० ॥५७॥ अल्विध्यर्थमिदम् । तथा हि-वव्रश्चेति उरदत्त्वे कृते 'न संप्रसारणे संप्रसारणम्' इति वकारस्य संप्रसारणनिषेधः स्थान्यलाश्रयः । एवमचितीकः, सुचितीकः, बहुचितीक इति 'चितेः कपि' इति दीर्घत्वे कृते 'ह्रस्वान्तेऽन्त्यात्पूर्वम्' इति स्थान्यलाश्रयः स्वरोऽस्माद्वचनाद्भवति ॥

(उद्योतः) अचः पर० ॥५७॥ पूर्वेणैव सिद्धे इदं किमर्थमत आह—अलिति ॥ उरदत्त्वे इति । अङ्गाक्षिप्तप्रत्ययपरत्वनिमित्तके-इति शेषः । लिट्यभ्यासस्येत्युभयेषांग्रहणाद् हलादिशेषात्प्राक् संप्रसारणे वस्य संप्रसारणात्तन्निषेधाच्च प्राक् नित्यत्वात्परत्वाच्चोरदत्वमिति भावः ॥ एवमचितीति । उत्तरपदस्याधिकृतस्य ह्रस्वेन विशेषणात्तदन्तग्रहणे लब्धे ह्रस्वान्ते इत्यत्रान्तग्रहणेन भूतपूर्वगतेराश्रयणेनेदं साधयितुं शक्यमिति कश्चित् ॥ तन्न । तदभावे ह्रस्वादावित्यर्थापत्तेः । ह्रस्वान्ते इत्यत्र नञ्सुभ्यामित्यनुवृत्तावपि बहोर्नञ्वदिति वचनात् 'बहुचितीकः' इत्युदाहृतम् ॥

(पदकृत्याधिकरणम्)

(अच्पदप्रयोजनम्)

(आक्षेपभाष्यम्)

अच इति किमर्थम् ?

(प्रदीपः) वार्तानि प्रत्युदाहरणानि कानिचिच्छक्यप्रतिविधानानीति प्रश्नः-अच इति किमर्थमिति ॥

(उद्योतः) प्रत्युदाहरणादिचिन्ता वृत्तिकाराणामुचिता, न तु भाष्यकृतोऽत आह—वार्त्तानीति । वृत्त्युदाहृतानि ॥

(प्रयोजनदर्शनभाष्यम्)

विश्नः, प्रश्नः । द्यूत्वा, स्यूत्वा । अक्षद्यूम् । आगत्य ॥

प्रश्नो विश्न इत्यत्र छकारस्य शकारः परनिमित्तकः, तस्य स्थानिवद्भावात् "छे च" इति तुक् प्राप्नोति । अच इति वचनान्न भवति ॥

(उद्योतः) भाष्ये—शकारः-च्छ्वोः शूडिति विहितः ॥

(दोषवारणभाष्यम्)

नैतदस्ति प्रयोजनम् । क्रियमाणेऽपि चाऽज्ग्रहणेऽवश्यमत्र तुगभावे यत्नः कर्तव्यः । अन्तरङ्गत्वाद्धि तुक् प्राप्नोति ॥

(प्रदीपः) अन्तरङ्गत्वादिति । अत एव युगपत्प्राप्त्यभावाद्वार्णादाङ्गं बलीय इत्येतदत्र नास्ति । यत्र हि युगपदाङ्गवार्णयोः प्राप्तिर्यथा कारकमिति वृद्धियणादेशयोः, यथा च किरतः-किरन्तीति यणित्त्वयोः, तत्रैतदुपतिष्ठते ॥ तत्रायं यत्नः-च्छ्वोः शूडिति तकारछकारयोः समुदायनिर्देशात्सतुक् छकारः स्थानी । समुदायनिर्देशसामर्थ्याच्चालोऽन्त्यस्येत्यस्यानुपस्थानम्, अनर्थकत्वाद्वा । एवं च नञो ङित्करणं 'विश्नः' इत्यत्र गुणनिषेधार्थमर्थवद्भवति ॥

(उद्योतः) अत एवेति । प्रत्ययनिरपेक्षतयाऽन्तरङ्गत्वेन तुकः शादेशात् प्राक् प्रवर्तनादेवेत्यर्थः ॥ अत्रान्तरङ्गत्वं प्रथमप्रवृत्तिकत्वरूपम् ॥ युगपदिति । बलाबलविचारस्य प्रतियोगिसापेक्षत्वेन तत्रैव संभवादिति भावः ॥ यथेति । 'कीरकः' 'किरति' इत्यादौ अन्तरङ्गत्वात्पूर्वमकादेशविकरणाविति भावः ॥ सतुगिति । यद्यप्यकृतव्यूहपरिभाषया तुगन्यावृत्तिः कर्तुं शक्या, तथापि तदभावस्यापि सतुक्निर्देशो ज्ञापकः । न च वान्छतेः क्विपि 'वान्छौ' इत्यादौ शाभावाय सतुकनिर्देश इति वाच्यम् । शादेशयोग्यप्रत्ययपरस्य वान्छतेः प्रयोगाभावात् । अत एव सतुक्निर्देशसामर्थ्यात्सर्वादेशः श इति पाठभाष्योक्तं सङ्गच्छते ॥ ननु सतुङ्निर्देशेऽपि तेनाङ्गविशेषणात्तदन्तविधौ अलोन्त्यस्येत्यन्त्यस्यैव स्यादत आह—समुदायेति ॥ अनर्थकत्वादिति । नानर्थक इति निषेधादिति भावः ॥ सतुक्छनिर्देशे लिङ्गमाह—एवं चेति[१४] ॥

(द्वितीयप्रयोजनोपपादनभाष्यम्)

इदं तर्हि-द्यूत्वा, स्यूत्वा । वकारस्य ऊठ् परनिमित्तकः । तस्य स्थानिवद्भावादचीति यणादेशो न प्राप्नोति । अच इति वचनाद्भवति ॥

(दोषवारणभाष्यम्)

एतदपि नास्ति प्रयोजनम् । स्वाश्रयमत्राच्त्वं भविष्यति ॥

अथवा-योऽत्रादेशो नासावाश्रीयते, यश्चाश्रीयते नासावादेशः ॥

(प्रदीपः) स्वाश्रयमिति । न ह्यतिदेशेन स्वाश्रया धर्मा निवर्त्यन्ते, यथा ब्राह्मणवदस्मिन् क्षत्रिये वर्तितव्यमिति क्षत्रियस्य क्षत्रियधर्माः । वाय्वोरित्यादौ तु सत्यपि स्वाश्रये वल्त्वे बहिरङ्गत्वाद्यणोऽसिद्धत्वाद्वलिलोपाभावः । द्यूत्वेत्यत्र तु नाजानन्तर्य इति असिद्धत्वनिषेधात् यण् प्रवर्तते । ऊठः स्थानिवत्त्वाद्वलोपः कथं नाशङ्कित इति चेत् । योऽनादिष्टादच इत्येवमर्थस्याऽज्ग्रहणस्य स्थापयिष्यमाणत्वात् ॥ योऽत्रादेश इति । समुदायरूप ऊठ् ॥ यश्चाश्रीयत इति । यण्विधावच् ॥ नासावादेश इति । समुदायस्यादेशत्वात् । न चादेशस्यावयव आदेशो गृह्यते । मुख्यसंभवे गौणग्रहणस्यायुक्तत्वात् ॥ ख्यात्रादीनां तद्यनुबन्धवियुक्तानां धातुसंज्ञा आदेशावयवत्वान्न प्राप्नोति । घस्लादेशस्य ऌदित्त्वादङर्थात् ज्ञापकाद्धातुकार्याणि भविष्यन्तीत्यदोषः ॥

(उद्द्योतः) न हीति । अयोगवाहेषु हलत्वाच्त्वयोः समावेशदर्शनेन तयोरविरोध इति भावः ॥ ननु स्वाश्रयानिवृत्तौ 'वाय्वोः' इत्यत्र दोषोऽत आह—वाय्वोरितीति ॥ असिद्धत्वनिषेधादिति । ऊठ इति शेषः ॥ बहिरङ्गपरिभाषाऽनित्यत्वादित्यन्ये ॥ योऽनादिष्टादच इति । अज्ग्रहणस्य सिद्धान्तरीत्या स्वान्यपेक्षया पूर्वत्वमाश्रीयत इत्यत्र तात्पर्यम् ॥ स्थापयिष्यमाणत्वादिति । व्याख्यास्यमानत्वादित्यर्थः ॥ अत्र स्वाश्रयकार्याभावातिदेशस्यापि सिद्धान्तयिष्यमाणत्वाद्भाष्ये परिहारान्तरं—अथवा योऽत्रेति ॥ अयं भावः—अभावातिदेशेऽपि स्थानिप्रयुक्तं भवति, आदेशप्रयुक्तं नेत्यर्थ इति । तदाह—समुदायेति । यथा सूत्रे सानुबन्धकग्रहणे तस्यानल्विधित्वम्, स्थानित्वं च नालः, तथा आदेशत्वमपि सूत्रोपात्तस्यैवेति भावः ॥ एवं च यण् नादेशप्रयुक्तः, किंतु तदवयवप्रयुक्त इति नासौ वार्यत इति तात्पर्यम् ॥ आदेशो गृह्यत इति । आदेश इति गृह्यते-इत्यर्थः ॥ न प्राप्नोतीति । स्थानिवत्त्वेनेति शेषः ॥

(तृतीयप्रयोजनोपपादनभाष्यम्)

इदं तर्हि प्रयोजनम्—अकाष्टाम् । सिचो लोपः परनिमित्तकः । तस्य स्थानिवद्भावात् "षढोः कः सि" (८।२।४१) इति कत्वं प्राप्नोति । अच इति वचनान्न भवति ॥

(दूषणनिराकरणभाष्यम्)

एतदपि नास्ति प्रयोजनम् । वक्ष्यत्येतत्-*पूर्वत्रासिद्धे न स्थानिवत्* इति ॥

(अखण्डितप्रयोजनभाष्यम्)

इदं तर्हि प्रयोजनम्—आगत्य, अभिगत्य । अनुनासिकलोपः परनिमित्तकः, तस्य स्थानिवद्भावात् 'ह्रस्वस्य' इति तुक् न प्राप्नोति ॥ अच इति वचनाद्भवति ॥

(उद्द्योतः) भाष्ये—आगत्येति । मलोपस्यापि ह्रस्वस्य पित्प्रत्ययपरत्वसंपादकतया तुग्विधावाश्रयणमित्यर्थः ॥ अभावातिदेशे चैतत्फलम् । अत एवाभावातिदेशे 'पटयति' इत्यादौ वृद्धिर्नेत्यमे भाष्यं संगच्छते ॥

(परस्मिन्नित्येतत्प्रयोजनम्)

(आक्षेपभाष्यम्)

अथ परस्मिन्निति किमर्थम् ?

(प्रयोजनभाष्यम्)

युवजानिः । द्विपदिका । वैयाघ्रपद्यः । आदीध्ये ॥

(प्रथमप्रयोजनोपपादनभाष्यम्)

युवजानिः, वधूजानिरिति "जायाया निङ्" (५।४।१३४) अपरनिमित्तकः । तस्य स्थानिवद्भावात् 'वलि' इति यलोपो न प्राप्नोति ॥ परस्मिन्निति वचनाद्भवति ॥

(प्रदीपः) युवजानिरिति । अव्युत्पन्नत्वादुणादीनां जाशब्दस्याकारलोपो न भवति । अन्यथाऽऽकारस्य निङि कृते यलोपे च निङः स्थानिवद्भावात्प्रत्ययत्वादाकारलोपः स्यात् । न चासिद्धवदत्राभादित्याकारलोपे कर्तव्येऽसिद्धत्वमात्वस्य, व्याश्रयत्वात् ॥

(उद्द्योतः) ननु स्वाश्रयवत्त्वादिना यलोपसिद्धावपि आलोपः स्थानिवत्त्वेन स्यादिति तद्वारणाय परग्रहणमावश्यकमेवेत्यत आह—अव्युत्पन्नत्वादिति ॥ आकारलोप इति । आतो लोप इत्यनेन । जनेरौणादिके यकि ये विभाषेत्यात्त्वे टापि तेनैकादेशे तस्य पूर्वान्तवद्भावादार्धधातुकत्वेन युवतिशब्देन बहुव्रीहौ निङादेशे यलोपेऽवशिष्टस्य स्थानिवत्त्वेनार्धधातुकत्वादिसत्त्वात् 'यातिः' इतिवदिति भावः ॥ ननु आभीयत्वेनात्त्वस्यासिद्धत्वाल्लोपो नेत्यत आह—न चेति ॥ व्याश्रयत्वादिति । ये आत्त्वम्, आस्थानिके निङि लोपः-इत्यात्त्वनिमित्तापेक्षया न्यूननिमित्तकत्वात् व्याश्रयता ॥

(प्रथमप्रयोजननिराकरणभाष्यम्)

नैतदस्ति प्रयोजनम् । स्वाश्रयमत्र वल्त्वं भविष्यति ॥

अथवा—योऽत्रादेशो नासावाश्रीयते । यश्चाश्रीयते नासावादेशः ॥

(द्वितीयप्रयोजनोपपादनभाष्यम्)

इदं तर्हि प्रयोजनम्-द्विपदिका, त्रिपदिका । पादस्य लोपोऽपरनिमित्तकः, तस्य स्थानिवद्भावात्पद्भावो न प्राप्नोति ॥ परस्मिन्निति वचनाद्भवति ॥

(उद्द्योतः) भाष्ये-द्विपदिकेति । द्वौ पादौ-इति तद्धितार्थेति समासे पादशतस्येति वुन्लोपौ ॥ परस्मिन्नितीति । सङ्विधाने परनिमित्तकत्वव्यवहाराभावादित्यर्थः ॥

(द्वितीयप्रयोजननिराकरणभाष्यम्)

एतदपि नास्ति प्रयोजनम् । पुनर्लोपवचनसामर्थ्यात् स्थानिवद्भावो न भविष्यति ॥

(प्रदीपः) पुनरिति । यस्येति लोपे सिद्धे पादशतस्येत्यत्र पुनर्लोपवचनं स्थानिवत्त्वनिषेधार्थम् । पुनर्लोपवचने सति लुप्यत एवाकारः, कार्ये नाऽऽश्रीयत इत्यर्थः ॥

(उद्द्योतः) पुनर्लोपवचनेन यथा स्थानिवत्त्वाभावस्तथाऽभिनयति—पुनर्लोपेति ।

(तृतीयप्रयोजनोपपादनभाष्यम्)

इदं तर्हि प्रयोजनम्—वैयाघ्रपद्यः ॥

(उद्द्योतः) (भाष्ये) वैयाघ्रपद्ये व्याघ्रस्येव पादावस्येति बहुव्रीहौ पादस्य लोप इति लोपे गर्गादित्वाद्यञि पादः पदिति पद्भावे न स्वाभ्यामित्यैच् ॥

(प्रयोजनबाधकाक्षेपभाष्यम्)

ननु चात्रापि पुनर्वचनसामर्थ्यादेव न भविष्यति ॥

(प्रदीपः) ननु चात्रापीति । यस्येति लोपे सिद्धे पादस्य लोप इति पुनर्लोपवचनादित्यर्थः ॥

(प्रयोजनसाधकभाष्यम्)

अस्ति ह्यन्यत्पुनर्लोपवचने प्रयोजनम् ॥

किम् ?

यत्र भसंज्ञा न—व्याघ्रपात्, श्येनपादिति ॥

(चतुर्थप्रयोजनोपपादनभाष्यम्)

इदं चाप्युदाहरणम्—आदीध्ये, आवेव्ये । इकारस्य एकारोऽपरनिमित्तकः । तस्य स्थानिवद्भावात् "यीवर्णयोर्दीधीवेव्योः" (७।४।५३) इति लोपः प्राप्नोति । परस्मिन्निति वचनान्न भवति ॥

(प्रदीपः) आदीध्य इति । इट एत्वे कृते लोपः प्राप्नोति विकरणश्च । तत्र नित्यत्वाद्विकरणः, तस्य लुक् ॥ एरनेकाच इति यण् न प्रवर्तते । क्विलुगुपधात्वचङ्परनिर्ह्रासकुत्वेष्विति स्थानिवत्त्वनिषेधात् ॥

(उद्योतः) ननु 'तस्य स्थानिवत्त्वात्' इत्ययुक्तम्, तेन विनाऽपि टित एत्वात् प्राक् यीवर्णयोरित्यस्य परत्वात्प्राप्तेरत आह—इट इति । अन्तरङ्गत्वादिति भावः ॥ नित्यत्वादिति । लोपस्तु विकरणे कृते तेन व्यवधानान्न प्राप्नोतीति भावः ॥ यद्यपि लुकि इलोपप्राप्तिः सोऽपि नित्यः, तथापि विकरणसंप्रधारणामात्रा भायेणेदम् ॥ ननु परस्मिन्नित्यस्याभावे शब्लुकः स्थानिवत्त्वेन एरनेकाच इति यण् स्यात् । तत्र च कृते यलोपे स्थानिवत्त्वनिषेधेन ईकारपरत्वाभावाद् न लोपप्राप्तिः, यलोपे लोपाजादेश एवेति नियमस्तु निमित्तभूताजादेशविषय एवास्तु । परस्मिन्निति च न कार्यमत आह—एरनेकाच इति ॥ एतेन शब्लुकः स्थानिवत्त्वेन व्यवधानात् यीवर्णयोरित्यस्य न प्राप्तिरित्यपास्तम् ॥

(इति परस्मिन्नित्येतत्प्रयोजननिरूपणम्)

(पूर्वविधिग्रहणप्रयोजनम्)

(आक्षेपभाष्यम्)

अथ पूर्वविधाविति किमर्थम् ?

(समाधानभाष्यम्)

हे गौः । बाभ्रवीयाः । नैधेयः ॥

(प्रथमप्रयोजनोपपादनभाष्यम्)

हे गौरिति औकारः परनिमित्तकः । तस्य स्थानिवद्भावात् "एङ्ह्रस्वात्संबुद्धेः" (६।१।६९) इति लोपः प्राप्नोति । 'पूर्वविधौ' इति वचनान्न भवति ॥

(प्रयोजननिराकरणभाष्यम्)

नैतदस्ति प्रयोजनम् । आचार्यप्रवृत्तिर्ज्ञापयति—'न संबुद्धिलोपे स्थानिवद्भावो भवति' इति । यदयं "एङ्ह्रस्वात्संबुद्धेः" इत्येङ्ग्रहणं करोति ॥

(प्रदीपः) यदयमिति । अग्ने-वायो-इति स्थानिवत्त्वात् ह्रस्वादित्येव लोपः सिद्धः । खट्वे-माले-इत्यादौ हल्ङ्याब्भ्य इति ॥ नयत्यादीनां विजन्तानां ने-लो-इति कथं संबुद्धिलोप इति चेत् । नैतेभ्यो विच् दृश्यते ॥

(उद्योतः) ह्रस्वादित्येवेति । सेस्मृतोशब्दादावप्येवम् ॥ यत्र स्थानिवत्त्वेऽपि न ह्रस्वान्तता तत्राह—खट्वे इति ॥ 'लोपः सिद्धः' इत्यनुषज्यते । स्थानिवत्त्वादेवेकाराकारप्रश्लेषेऽपि न दोषः ॥ नैतेभ्य इति । एवं दीर्घैकारान्तप्रकृतिक'से'इत्यादीनामेकाक्षरकोशबोधितस्य 'ए'इत्यस्य च संबद्धावभिधानाभावो बोध्यः ॥ अत्रेदं चिन्त्यम्—ओग्रहणस्य भाष्ये कृतत्वेन दीर्घौकारान्तप्रकृतिकओकारान्तानभिधाने मानाभावः । गोर्थमिति भाष्यं तु बोशब्दस्य सर्वसंमतया ओकारान्तोपलक्षणतया व्याख्येयमेव सर्वैः ॥ किंच संबुद्धावनभिधानेनोपपत्तौ सर्वथा विजभावकल्पना कुत इति ॥

अपरे तु पूर्वविधावित्यस्याभावेऽयं विचारः । तत्र दीर्घान्तप्रकृतिक-एकारान्ते स्थानिवत्त्वेनैङोऽभावात् विनाऽतिदेशबाधं प्रत्याहारग्रहणचारितार्थ्यस्य वक्तुमशक्यत्वादनभिधानकल्पने न मानम् । न चेदं भाष्यमभावातिदेशानङ्गीकारेणैव प्रवृत्तमिति वाच्यम् । अथ वा योऽत्रादेश इति भाष्येण तदाश्रयणात् । 'आगत्य' 'वैयाघ्रपद्यः' इत्यत्र ईत्वादेः प्रत्युदाहरणेन तदाश्रयणाचेत्याहुः ॥

(प्रयोजनसाधकभाष्यम्)

नैतदस्ति ज्ञापकम् । गोऽर्थमेतत् स्यात् ॥

(उद्योतः) भाष्ये—गोर्थमेतदिति । अनिष्टलोपसिद्ध्यर्थमेव तत्, स्थानिवद्भावेनैङ्त्वादिति भावः ॥

(प्रयोजनबाधकज्ञापकाशयान्तरभाष्यम्)

यत्तर्हि प्रत्याहारग्रहणं करोति । इतरथा हि 'ओह्रस्वात्' इत्येव ब्रूयात् ॥

(द्वितीयप्रयोजनोपपादनभाष्यम्)

इदं तर्हि प्रयोजनम्—बाभ्रवीयाः, माधवीयाः । वान्तादेशः परनिमित्तकः, तस्य स्थानिवद्भावात् "हलस्तद्धितस्य" (६।४।१५०) इति यलोपो न प्राप्नोति ॥ पूर्वविधाविति वचनाद्भवति ॥

(प्रदीपः) बाभ्रवीया इति । सन्निपातपरिभाषाया अनित्यत्वाद्यशब्दसन्निपातनिमित्तो वान्तादेशो यलोपनिमित्ततां प्रतिपद्यते ॥

(उद्योतः) बाभ्रवीया इति । मधुबभ्र्वोरिति यञि वृद्धावोर्गुणेऽवि वृद्धाच्छे यस्येति लोपे हलस्तद्धितस्येति सूत्राद्धलइत्यनुवर्तमाने आपत्यस्येति सूत्रेण यलोपः ॥ ननु तत्र सिद्धान्तेऽपि यनिमित्तो वान्तादेशः कथं यलोपनिमित्तं स्यादत आह—संनिपातेति ॥

(प्रयोजननिराकरणभाष्यम्)

एतदपि नास्ति प्रयोजनम् । स्वाश्रयमत्र हल्त्वं भविष्यति ॥

अथवा—योऽत्रादेशो नासावाश्रीयते, यश्चाश्रीयते नाऽसावादेशः ॥

(प्रदीपः) योऽत्रादेश इति । वान्तः समुदायः ॥ **यश्चेति ।** लोपं प्रति निमित्तत्वेन वकारः ॥

(तृतीयप्रयोजनोपपादनभाष्यम्)

इदं तर्हि प्रयोजनम्—नैधेयः । आकारलोपः परनिमित्तकः, तस्य स्थानिवद्भावाद् द्व्यज्लक्षणो ढक् न प्राप्नोति ॥ पूर्वविधाविति वचनाद्भवति ॥

(प्रदीपः) नैधेय इति । स्थानिवद्भावात् त्र्यच्कत्वव्यपदेशे सति विरोधात् स्वाश्रयं द्व्यच्त्वं न लभ्यते । यैदविरुद्धं स्वाश्रयं तदतिदेशेन न बाध्यते, विरुद्धं तु बाध्यत एव । संख्याकृतस्तु व्यपदेशः परस्परपरिहारेण लोके स्थितः । न हि त्रिपुत्रो द्विपुत्रव्यपदेशं लभते ॥

(उद्योतः) (भाष्ये) **नैधेय इति ।** निपूर्वाद्धाञः किप्रत्यये आतो लोपे गतिसमासे द्व्यच इतश्चानिञ इति ढक् ॥

(इति पूर्वविधिग्रहणप्रयोजननिरूपणम्)

(अथ विधिग्रहणप्रयोजननिरूपणम्)

(आक्षेपभाष्यम्)

अथ विधिग्रहणं किमर्थम् ?

(प्रदीपः) अथेति । 'अचः परस्मिन् पूर्वस्य' इत्येव षष्ठ्या विध्यर्थ आक्षिप्तः – पूर्वस्य कार्ये कर्तव्य इति । कार्यं च विधिरिति प्रश्नः ।

(समाधानभाष्यम्)

सर्वविभक्त्यन्तः समासो यथा विज्ञायेत—पूर्वस्य विधिः पूर्वविधिः, पूर्वस्माद्विधिः पूर्वविधिरिति ॥

(अथ पञ्चमीसमासप्रयोजननिरूपणम्)

(आक्षेपभाष्यम्)

कानि पुनः पूर्वस्माद्विधौ स्थानिवत्त्वस्य प्रयोजनानि ?

(प्रयोजनोद्देशभाष्यम्)

बेभिदिता, चेच्छिदिता । माथितिकः । अपीपचन् ॥

(प्रथमप्रयोजनोपपादनभाष्यम्)

बेभिदिता चेच्छिदितेति । अकारलोपे कृते यलोपे च एकाज्लक्षण इट्प्रतिषेधः प्राप्नोति ॥ स्थानिवद्भावान्न भवति ॥

(प्रदीपः) बेभिदितेति । बेभिद्यशब्दात्तृच् । नित्यत्वादल्लोपयलोपौ । ततः 'एकाच–' इतीट्प्रतिषेधः प्राप्नोति । **उपदेशग्रहणं** द्वयोरपि विशेषणम्–उपदेशे एकाचः, उपदेशेऽनुदात्तादिति । द्विष्प्रयोगश्च द्विर्वचनम् । अल्लोपस्य तु स्थानिवत्त्वे व्यवधानादिट्प्रतिषेधाभावः ॥

(उद्योतः) ननु च बेभिदितेत्यत्राल्लोपयलोपाभ्यां प्रागेव परत्वादिट्, न च तदा प्रतिषेधप्राप्तिरत आह—**नित्यत्वादिति ।** सत इत्यनेनेटोऽनित्यत्वमुक्तम् ॥ ननु कृतद्विर्वचनं नैकाजत आह—**उपदेशेति** ॥ ननु भिद् भिद् इति द्विर्वचनरूपादेशस्य न भिद्युपदेश उपदेश इति कथमुपदेशे एकाच्त्वमत आह—**द्विःप्रयोगश्चेति ।** लोपेऽवशिष्टस्य 'बेभिद्' इत्यस्य स उपदेश इति भावः ॥ **परे तु एकाच उपदेश** इत्यत्र **एकाचो द्वे** इति सूत्रस्थभाष्यरीत्या विहितविशेषणाश्रयणादङ्गसंज्ञायामल्लोपस्य [धङिके भसंज्ञायामल्लोपस्येव] स्थानिवत्त्वेन तृजादिनिरूपिताङ्गत्वस्य बेभिदिति समुदायेऽभावाच्च पञ्चमीसमासं विनाऽपि नात्रानुपपत्तिरित्याहुः ॥

(द्वितीयप्रयोजनोपपादनभाष्यम्)

माथितिक इति । अकारलोपे कृते 'तान्तात्कः' (७।३।५१) इति कादेशः प्राप्नोति ॥ स्थानिवद्भावान्न भवति ॥

(प्रदीपः) माथितिक इति । यदा 'ठस्येकः' इति संघातग्रहणम्, तदा स्थानिवद्भावादिकस्य कादेशः प्राप्नोति । वर्णनिर्देशे त्वल्विधित्वात् कादेशस्याप्रसङ्गः । **सन्निपातपरिभाषां** चानाश्रित्यैतदुक्तम् ॥

(उद्योतः) वर्णनिर्देशे त्विति । स्थानिन्यकारो न विवक्षित इति वर्ण एव तत्र स्थानी, ठगादिप्रत्ययेष्वप्यकारस्तथैव । औदेशे च विवक्षित इति ठत्वाभावात्प्राप्तिरेव नेति भावः ॥ **संनिपातेति ।** इदं च ठक्छसोश्चेति वार्तिकभाष्ये स्पष्टम् ॥

(तृतीयप्रयोजनोपपादनभाष्यम्)

अपीपचन्निति । एकादेशे कृते 'अभ्यस्ताज्झेर्जुस् भवति' इति जुस्भावः प्राप्नोति ॥ स्थानिवद्भावान्न भवति ॥

(प्रदीपः) अपीपचन्निति । झेः 'इतश्च' इतीकारलोपे कृते **एकदेशविकृतमनन्यवदि**ति झिरेवायम्, तत्रान्तादेशे कृते चङ्कारस्य पररूपे कृते तस्यादिवद्भावाज्जुस् प्राप्नोति ॥ स्थानिवद्भावे तु णिलोपस्य पररूपस्य वा व्यवधानात् न भवति ॥ ननु पूर्वस्माद्विधौ स्थानिवद्भावे कथं द्वे गौरित्यादि सिध्यति ॥ उच्यते—अचो यः पूर्वस्तस्मान्निमित्तत्वेनाश्रितादित्याश्रयणात् ॥ तथाहि—गोशब्दे ओकारात् पूर्वो गकारः, न च तस्मादत्र विधिरस्ति ॥

(उद्योतः) न भवतीति । न च 'अपीपचन्' इत्यत्र न पदान्तेति निषेधात्स्थानिवद्भावो दुर्लभ इति वाच्यम् । पदचरमावयवे कर्तव्ये आदेशस्य पदान्तरस्यैव ग्रहणादत्र तदप्राप्तेः । पदेऽन्त इत्यर्थस्य भाष्ये वक्ष्यमाणत्वेनैतदर्थलाभः ॥ **केचित्तु** पूर्वोत्तरसाहचर्येणाभ्यस्तस्य भावरूपादेशानपहृतविकरणकस्य ग्रहणादत्र, प्रत्येपिषन्नित्यादौ च न दोष इत्याहुः ॥ वस्तुत ईदृशसाहचर्याश्रयणापेक्षया पञ्चमीसमासाश्रयणे गौरवाभाव इत्यपीपचन्निति तदुदाहरणमेव बोध्यम् ॥ **न च तस्मादिति ।** निमित्तत्वेनाश्रितादिति शेषः ॥ वस्तुतो **निमित्तत्वेनाश्रिता**दित्यस्य व्यवधानोपलक्षणम् ॥ **न च तस्मादिति ।** ओकारेण व्यवधानादित्यर्थः ॥ तदंशे निर्दिष्टपरिभाषाबाधे मानाभावादिदमेव युक्तम् । **निमित्तत्वेने**त्यादेः शब्दमर्यादयाऽलाभाच्च । अत एव तथाहि **गोशब्द**-इत्यादि सार्थकम् । अन्यथो-

त्कार्थस्योपपादनानपेक्षत्वेन तद्वैयर्थ्यम् । निमित्तत्वेनाश्रितादित्येतद्रहितस्यायुक्तत्वं चेत्यन्ये ॥

(उक्तप्रयोजननिराकरणभाष्यम्)

नैतानि सन्ति प्रयोजनानि । प्रातिपदिकनिर्देशोऽयम् । प्रातिपदिकनिर्देशास्त्वर्थतन्त्रा भवन्ति, न कांचित्प्राधान्येन विभक्तिमाश्रयन्ति । तत्र प्रातिपदिकार्थे निर्दिष्टे यां यां विभक्तिमाश्रयितुं बुद्धिरुपजायते, सा साऽऽश्रयितव्या ॥

(विधिग्रहणप्रयोजनान्तरभाष्यम्)

इदं तर्हि प्रयोजनम्—विधिमात्रे स्थानिवत् यथा स्यात् । अनाश्रीयमाणायामपि प्रकृतौ । वाय्वोः, अध्वर्य्वोः । "लोपो व्योर्वलि" (६।१।६६) इति यलोपो मा भूदिति ॥

(प्रदीपः) **विधिमात्र इति । अचः परस्मिन् पूर्वस्ये**त्यनेन स्थानिवद्भावे विहिते पुनर्विधाविति वचनं नियमार्थं स्थानिवदेव यथा स्यात्, मा भूत् स्वाश्रयमित्यर्थः ॥ **अनाश्रीयमाणायामिति** । कार्ये निमित्तत्वेनेत्यर्थः ॥

(उद्योतः) ननु विधिग्रहणे कृतेऽपि कथं स्थानिवत्त्वेन स्वाश्रयनिवृत्तिरत आह—**अच इति । अचः परस्मिन्पूर्व-**इत्येको योगः । **पूर्वे**ति लुप्तविभक्तिकम् । **विधौ**-इति द्वितीयः । तेन स्थानिवदेवेति नियमाश्रयणमिति भावः ॥ भाष्ये—**विधिमात्रे**-इत्यस्य विवरणम**नाश्रीयमाणायामपि प्रकृता**विति । स्थानिनीत्यर्थः ॥ **वाय्वोरिति** । अत्र न बहिरङ्गासिद्धत्वं, उभयोर्वर्णनिमित्तत्वेन समत्वात् । पूर्वं पूर्वमन्तरङ्गमित्यपि युगपत्प्राप्तौ पूर्वमन्तरङ्गं नाप्तिनियामकं, न तु जातस्यासिद्धत्वे-इति भावः ॥

(भाष्यम्)

अस्ति प्रयोजनमेतत् ॥

किं तर्हीति ॥

(स्वविधौ स्थानिवद्भावनिरूपणम्)

(आक्षेपबाधकं भाष्यवार्तिकम्)

॥ अपरविधाविति तु वक्तव्यम् ॥

(भाष्यम्)

किं प्रयोजनम् ?

स्वविधावपि स्थानिवद्भावो यथा स्यात् ॥

(उद्योतः) भाष्ये स्वशब्देन स्थान्यादेशश्चोच्यते । **अपरविधाविति तु वक्तव्य**मित्यारभ्य **कथं यानि स्वविधौ स्थानिवद्भावस्य प्रयोजनानी**त्यन्ता एकदेश्युक्तिः, आयन्नासन्नित्यनयोरसिद्धवत्सूत्रेण सिद्धेः ॥ धिन्वन्तीत्यादावुकारवृत्त्यार्धधातुकत्वस्यालधर्मत्वेन वस्य दुर्लभत्वादिटोऽप्राप्तेः । सिद्धान्तिनाऽपि भावसाधनविधिशब्दस्याप्युपादानमत्रेति सिद्धान्तं बोधयितुं तन्नोक्तम् ॥

(आक्षेपभाष्यम्)

कानि पुनः स्वविधौ स्थानिवद्भावस्य प्रयोजनानि ?

(प्रयोजनोद्देशभाष्यम्)

आयन्, आसन् । धिन्वन्ति, कृण्वन्ति । दध्यत्र, मध्वत्र । चक्रतुः, चक्रुः ॥

(प्रथमप्रयोजनोपपादनभाष्यम्)

इह तावत्—आयन् आसन्निति । इणस्त्योर्यण्लोपयोः कृतयोरनजादित्वात् "आडजादीनाम्" (६।४।७२) इत्याट् न प्राप्नोति ॥ स्थानिवद्भावाद् भवति ॥

(प्रदीपः) **आयन्निति** । अजादेरेवाड्विधानात्स्वविधिराट् ॥

(द्वितीयप्रयोजनोपपादनभाष्यम्)

धिन्वन्ति कृण्वन्तीति । यणादेशे कृते वलादिलक्षण इट् प्राप्नोति ॥ स्थानिवद्भावान्न भवति ॥

(उद्योतः) भाष्ये—**धिन्वन्तीत्यादि** । यद्यप्यङ्गात्परस्य वलादेरिडित्यर्थात्पूर्वविधावित्युक्तावपि पञ्चमीसमासेनेदं सिध्यति, तथापि अङ्गसंज्ञानिमित्तस्येत्यर्थं इत्यभिप्रायेणेदमित्याहुः ॥

(तृतीयप्रयोजनोपपादनभाष्यम्)

दध्यत्र मध्वत्रेति । यणादेशे कृते संयोगान्तलोपः प्राप्नोति ॥ स्थानिवद्भावान्न भवति ॥

(प्रदीपः) **दध्यत्रेति । पूर्वत्रासिद्धे न स्थानिवदि**त्येतदत्र नास्ति, **तस्य दोषः संयोगादिलोपलत्वणत्वे**ष्वित्यत्र संयोगादिलोपस्य संयोगोपलक्षितलोपोपलक्षणार्थत्वात् । पदान्तविधिं प्रति नेत्ययमपि प्रतिषेधोऽत्र नास्ति । पदान्ते विधातव्ये स प्रतिषेधः । न च लोपोऽभावात्मकत्वात्पदान्तः ॥

(उद्योतः) **उपलक्षणार्थत्वादिति** । इदमन्यत्यग्रन्थयोजनमात्रम्, न त्वयं सिद्धान्त इति बोध्यम् । अत एवादिपदं चरितार्थम् । **यणः प्रतिषेधो वाच्य** इतिवदिदमनाश्रित्येदमिति तत्त्वम् ॥ **पदान्ते विधातव्ये इति** । पदचरमावयवे कर्तव्ये-इत्यर्थः ॥

(चतुर्थप्रयोजनोपपादनभाष्यम्)

चक्रतुः चक्रुः । यणादेशे कृते अनच्कत्वात् द्विर्वचनं न प्राप्नोति ॥ स्थानिवद्भावाद् भवति ॥

(प्रदीपः) **चक्रतुरिति** । अत्र साच्कस्य द्विर्वचनमिति स्वविधिर्भवति । ततश्च **द्विर्वचनेऽची**त्येतन्न वक्तव्यं भवति ॥ नन्वपरविधावित्युच्यमाने कथं बेभिदितेत्यादयः संगृह्यन्ते । उच्यते—निमित्तापेक्षया परत्वविज्ञानात् । तथाहि—**बेभिदिते**त्यत्राकारलोपस्य निमित्तमार्धधातुकम् । न च तस्मात्परस्य विधिः । किं तर्हि ? तस्यैवेति सिद्धः स्थानिवद्भावः । एवं **माथितिकः-अपीपचन्नि**त्यत्र बोद्धव्यम् । **हे गौरि**त्यत्र तु

स्थानिवद्भावः प्राप्तः, एङिति प्रत्याहारग्रहणाच्च भवति । वाभ्रवीया इत्यत्र योऽत्रादेशो नासावाश्रीयते इति परिहारः ॥ नैधेय इत्यत्र तु निमित्तात्परस्य ढको विधिरिति स्थानिवत्त्वाभावः ॥

(उद्द्योतः) तत्रश्चेति । एवं च तत्सूत्राकरणलाघवानुरोधेनापरविधाविल्येव वक्तव्यमिति भावः ॥ निन्यतुरित्यादिसिद्धये तस्यावश्यकत्वाच्चिन्त्यमिदम् । भाष्ये तु संभवमात्रेणेदमुदाहृतम् । उरदत्वमपि स्थानिवद्भावेनैव सुलभं लक्ष्यविशेषे । लक्ष्यानुरोधादयमपि रूपातिदेश इति वा कैयटाशयः ॥ स्थान्यादेशयोरन्यतरापेक्षया परत्वमाश्रित्य शङ्कते—नन्विति ॥ निमित्तेति । निमित्तं च यस्य स्थानिवत्त्वं तदीयं ग्राह्यम् । किंत्विदमयुक्तम् । एतन्न्यासखण्डनायाग्रे भगवता निमित्तस्यावधिताया वक्ष्यमाणतया तदनाश्रयणेनैवैतद्भाष्यप्रवृत्तेः । अपरविधाविति न्यासेऽपि पञ्चमीसमासस्य वक्तुं शक्यत्वे तत्संग्रह इत्युचितम् ॥ वार्तिकं तु स्वविधिसंग्रहार्थमिति स्पष्टमेव ॥ न चात्र पञ्चमीसमासे हे गौरित्यत्र स्वस्मात्परस्य विधावपि स्थानिवत्त्वं स्यादिति वाच्यम् । पञ्चमीसमासानित्यत्वेनादोषात् ॥ प्रत्याहारग्रहणाद्विति । से स्मृतो इत्यादीनामनभिधानाश्रयेणैतदुक्तम् ॥ ननु वाभ्रवीया इत्यत्रापत्यस्येति लोपेऽवादेशस्य स्थानिवत्त्वं स्यात् । अवादेशनिमित्तयादिप्रत्ययसंबन्धिन एव विधेः सत्त्वात् । न च नपदान्तेति निषेधः, स्वरदीर्घयलोपेषु लोपाजादेशस्यैव स्थानिवत्त्वनिषेधादत आह—वाभ्रवीया इति ॥ ढको विधिरिति । विधिशब्दो भावसाधनः, संबन्धसामान्यषष्ठ्या समास इति भावः ॥

(अनिष्टापत्तिभाष्यम्)

यदि तर्हि स्वविधावपि स्थानिवद्भावो भवति । 'द्याभ्याम्, धेयम्, लवनम्' अत्रापि प्राप्नोति ॥

द्याभ्यामिति । अत्रात्त्वस्य स्थानिवद्भावाद् दीर्घत्वं न प्राप्नोति ॥

धेयमिति । ईत्त्वस्य स्थानिवद्भावाद् गुणो न प्राप्नोति ॥

लवनमिति । अत्र गुणस्य स्थानिवद्भावादवादेशो न प्राप्नोति ।

(अनिष्टापत्तिवारणभाष्यम्)

नैष दोषः । स्वाश्रया एते विधयो भविष्यन्ति ॥

(प्रदीपः) स्वाश्रया इति । विधिग्रहणं स्वाश्रयनिवृत्त्यर्थं व्याख्यातमिति स्वाश्रया इत्यन्यथा व्याख्यायते—शब्दानां स्वं आत्मीयं लक्षणम् । तेन ज्ञापकाश्रया इत्यर्थः । "द्व्योरेकस्य डतरच्" "धेयमृणे" "किरतौ लवने" इत्यादिज्ञापकमादेशाश्रयकार्यभावस्य ॥

(उद्द्योतः) द्व्योरेकस्येत्यादिनिर्देशात् स्वविधौ स्थानिवत्त्वमनित्यमिति वाभ्रवीयनैधेययोर्न दोष इति परे ॥

(आक्षेपभाष्यम्)

तर्हि वक्तव्यम्—अपरविधाविति ।

(समाधानभाष्यम्)

न वक्तव्यम् । पूर्वविधावित्येव सिद्धम् ॥

कथम् ?

न पूर्वग्रहणेनादेशोऽभिसंबध्यते—'अजादेशः परनिमित्तकः पूर्वस्य विधिं प्रति स्थानिवद् भवति ।

कुतः पूर्वस्य ? आदेशात्' इति ॥

किं तर्हि ?

निमित्तमभिसंबध्यते—'अजादेशः परनिमित्तकः पूर्वस्य विधिं प्रति स्थानिवद् भवति ।

कुतः पूर्वस्य ? निमित्तात्' इति ॥

(प्रदीपः) निमित्तमिति । आयन्नित्यादिषु च निमित्तात् पूर्वस्य विधिरिति सिद्धः स्थानिवद्भावः ॥

(आक्षेपभाष्यम्)

अथ निमित्तेऽभिसंबध्यमाने यत्तदस्य योगस्य मूर्धाभिषिक्तमुदाहरणं तदपि संगृहीतं भवति ॥

किं पुनस्तत् ?

पट्व्या-मृद्व्येति ॥

(प्रदीपः) मूर्द्धाभिषिक्तमिति । सर्ववृत्तिषूदाहृतत्वात् । पटु-ई-आ-इति स्थिते परयणादेशेनाकारस्य व्यवधानात्प्रश्नः ॥

(उद्द्योतः) भाष्ये—अथेत्यादिना संगृहीतमित्यन्तेन काक्वा प्रश्नः । तदेवाह—व्यवधानात्प्रश्न इति ॥

(समाधानभाष्यम्)

बाढं संगृहीतम् ॥

(समाधानबाधकभाष्यम्)

ननु च ईकारयणा व्यवहितत्वान्नासौ निमित्तात् पूर्वो भवति ॥

(समाधानसाधकभाष्यम्)

व्यवहितेऽपि पूर्वशब्दो वर्तते । तद्यथा—पूर्वं मथुरायाः पाटलिपुत्रमिति ॥

(प्रदीपः) व्यवहितेऽपीति । 'पूर्वस्य' इति साक्षान्निर्देशात्तस्मिन्निति निर्दिष्ट इत्यस्यानुपस्थानादिति भावः ॥

(उद्द्योतः) साक्षादिति । एवं च उत्तरस्येत्यस्यानुपस्थाने तदर्थं निर्दिष्टग्रहणमपि नोपतिष्ठत इति भावः ॥ तस्मादिति सूत्रे तस्मिन्नित्यतोऽनुवर्तमानस्य निर्दिष्टस्येत्यर्थः ॥ स्वरेग्रहणाच्च लिङ्गादत्र सूत्रे तदनुपस्थितिर्बोध्या ॥

(पक्षान्तराभ्युपगमभाष्यम्)

अथवा—पुनरस्तु आदेश एवाभिसंबध्यते ॥

(आक्षेपभाष्यम्)

कथं यानि स्वविधौ स्थानिवद्भावस्य प्रयोजनानि ?

(इत्येकदेशिभाष्यम्)

—ooxoo—

(अथ सिद्धान्तिभाष्यम्)

नैतानि सन्ति । इह तावत्—आयन्-आसन्-धिन्वन्ति-कृण्वन्तीति ।

अयं विधिशब्दोऽस्त्येवकर्मसाधनः—विधीयते-विधिरिति ।

अस्ति च भावसाधनः—विधानं-विधिरिति ।

तत्र कर्मसाधनस्य विधिशब्दस्योपादाने न सर्वमिष्टं संगृहीतमिति कृत्वा भावसाधनस्य विधिशब्दस्योपादानं विज्ञास्यते—पूर्वस्य विधानं प्रति पूर्वस्य भावं प्रति पूर्वः स्यादिति स्थानिवद्भवतीति ॥ एवमाट् भविष्यति । इट् च न भविष्यति ॥

(प्रदीपः) भावसाधनस्येति । भावसाधन एव विधिशब्दो व्यापकत्वादाश्रीयते । 'पूर्वस्य' इति च षष्ठी संबन्धसामान्ये विज्ञायते ॥ इट् च नेति । विधिग्रहणं स्वाश्रयनिवारणार्थमितीडभावः ॥

(उद्योतः) संबन्धसामान्ये इति । न तु कर्मणीत्यर्थः । तेन सर्वलक्ष्यसिद्धिरिति भावः ॥ भाष्ये—पूर्वः स्यादिति । पूर्वो न स्यादित्यस्याप्युपलक्षणम् । तदाह—स्वाश्रयनिवारणार्थमिति । एवं च प्रकृतसूत्रे उभयोरपि ग्रहणं बोध्यम् ॥ कैयटे—भावसाधन एवेति । एवशब्दोऽप्यर्थ इति केचित् ॥ न पदान्तसूत्रे एतत्स्फुटं वक्ष्यते ॥

(सिद्धान्तिशेषभाष्यम्)

दध्यत्र चक्रतुः चक्रुरिति परिहारं वक्ष्यति ॥

(उद्योतः) भाष्ये—परिहारं वक्ष्यतीति । दध्यत्रेत्यत्र—यणः प्रतिषेधारम्भः । चक्रतुरित्यादौ—द्विर्वचनेऽचीति ॥

(सूत्रप्रयोजनाधिकरणम्)

(आक्षेपभाष्यम्)

कानि पुनरस्य योगस्य प्रयोजनानि ?

(प्रयोजनश्लोकभाष्यम्)

॥ * ॥ स्तोष्याम्यहं पादिकमौदवाहिं
ततः श्वोभूते शातनीं पातनीं च ।
नेतारावागच्छतं धारणिं रावणिं च
ततः पश्चात्स्रंस्यते ध्वंस्यते च ॥ १ ॥*॥

(उपपादनभाष्यम्)

इह तावत्—पादिकं-औदवाहिं-शातनीं-पातनीं-धारणिं-रावणिमिति । अकारलोपे कृते पद्भावः-ऊठ्-अल्लोपः-टिलोप इत्येते विधयः प्राप्नुवन्ति ॥ स्थानिवद्भावान्न भवन्ति ॥

स्रंस्यते-ध्वंस्यते । णिलोपे कृते "अनिदितां हल उपधायाः क्ङिति" इति नलोपः प्राप्नोति ॥ स्थानिवद्भावान्न भवति ॥

(प्रदीपः) स्तोष्यामीति । कथयिष्यामीत्यर्थः ॥ पादिकमिति । पादोऽस्यास्तीति ठन् । दीव्यत्यादिषु वाऽर्थेषु ठक् ॥ चरत्यर्थे तु पदिक इत्येव भवति । पर्पादित्वात् ॥ उदकं वहतीत्यण् । संज्ञायामुदभावः, अपत्ये इञ् ॥ श्वोभूतिर्नाम शिष्यः, तस्यामन्त्रणम् ॥ शातनपातनशब्दाभ्यां गौरादित्वात् ङीष् ॥ नेताराविति शिष्ययोरामन्त्रणम् । नयेते गुरुमुखात् शास्त्रार्थ—नेतारौ ॥ धारणरावणशब्दाभ्यामिञ् ॥

(उद्योतः) चरत्यर्थे इति । पद्भाव इकेचरतावित्युपसङ्ख्यानादिति भावः ॥ गौरादित्वादिति । शदेर्ण्यन्ताद्युजिति भावः ॥ टित्वान्ङीबिति सप्तमे आकरः ॥ शातनीमित्यादावल्लोपोऽन इत्यल्लोपप्राप्तिः ॥ धारणिमित्यादि । धृरुभ्यां ण्यन्ताभ्यां ल्युटि णत्वस्यासिद्धत्वान्नस्तद्धित इत्यस्य प्राप्तिः ॥

(प्रयोजननिराकरणभाष्यम्)

नैतानि सन्ति प्रयोजनानि । "असिद्धवदत्राभात्" इत्यनेनाप्येतानि सिद्धानि ॥

(प्रयोजनान्तरभाष्यम्)

इदं तर्हि प्रयोजनम्—याज्यते-वाप्यते । णिलोपे कृते '—यजादीनां किति' इति संप्रसारणं प्राप्नोति ॥ स्थानिवद्भावान्न भवति ॥

(प्रयोजननिराकरणभाष्यम्)

एतदपि नास्ति प्रयोजनम् । यजादिभिरत्र कितं विशेषयिष्यामः—यजादीनां यः किदिति ॥

कश्च यजादीनां कित् ?

यजादिभ्यो यो विहित इति । न चाऽयं यजादिभ्यो विहितः ॥

(उद्योतः) भाष्ये—यजादिभ्यो विहित इति । एवं च वच्यादिभ्यो ण्यन्तेभ्यः क्विपि संप्रसारणं न भवत्येव । क्विब्भाव एवेत्यन्ये ॥

(मूर्धाभिषिक्तप्रयोजनान्तरभाष्यम्)

इदं तर्हि प्रयोजनम्—पट्व्या मृद्व्येति । परस्य यणादेशे कृते पूर्वस्य न प्राप्नोति, ईकारयणा व्यवहितत्वात् ॥ स्थानिवद्भावाद्भवति ॥

(आक्षेपभाष्यम्)

किं पुनः कारणं परस्य तावद्भवति, न पुनः पूर्वस्य ?

(आक्षेपनिराकरणभाष्यम्)

नित्यत्वात् । नित्यः परयणादेशः । कृतेऽपि पूर्वयणादेशे प्राप्नोति, अकृतेऽपि प्राप्नोति । नित्यत्वात्परयणादेशे कृते पूर्वस्य न प्राप्नोति ॥ स्थानिवद्भावाद्भवति ॥

(असिद्धपरिभाषया सूत्रप्रयोजननिराकरणभाष्यम्)

एतदपि नास्ति प्रयोजनम् । 'असिद्धं बहिरङ्गलक्षणमन्तरङ्गलक्षणे' इति । असिद्धत्वाद्बहिरङ्गल-

क्षणस्य परयणादेशस्यान्तरङ्गलक्षणः पूर्वयणादेशो भविष्यति ॥

अवश्यं चैषा परिभाषा आश्रयितव्या स्वरार्थम् । कर्त्र्यां-हर्त्र्येति "उदात्तयणो हल्पूर्वात्" इत्येष स्वरो यथा स्यात् ॥

(प्रदीपः) असिद्धं बहिरङ्गेति । नित्यादप्यन्तरङ्गं बलीय इति न्यायात् प्रथमं पूर्वस्य यण् इति भावः ॥ अवश्यं चेति । स्थानिवद्भावाश्रयणेऽपीत्यर्थः ॥ कर्त्र्येति । कर्तृ-ई-आ-इति स्थिते यदि नित्यत्वात् पूर्वं परयणादेशः स्यात्तस्य च स्थानिवद्भावात् पूर्वस्य यण्, तत उदात्तयणोऽनन्तर आकारो न भवतीत्युदात्तत्वं न स्यात् । यदा त्वन्तरङ्गत्वात् पूर्वं पूर्वयणादेशस्तदा ङीपः 'उदात्तयणो-' इति उदात्तत्वं, तस्यापि यणि कृते आकारस्योदात्तत्वमिति सिद्धमिष्टम् ॥

(उद्द्योतः) नित्यादपीति । नाजानन्तर्ये इति निषेधस्तु अनित्यो नास्त्येव वेति भाष्याशयः ॥ पूर्वनिमित्तकार्यत्वमात्रान्तरङ्गत्वं विवक्षितम् ॥

(सूत्रप्रयोजनवादिभाष्यम्)

अनेनापि सिद्धः स्वरः ॥

कथम् ?

(सिद्ध्युपायश्लोकवार्तिकम्)

॥ आरभ्यमाणे नित्योऽसौ ॥

(व्याख्याभाष्यम्)

आरभ्यमाणे त्वस्मिन् योगे नित्यः पूर्वयणादेशः । कृतेऽपि परयणादेशे प्राप्नोति, अकृतेऽपि ॥

(प्रदीपः) अनेनापीति । सति स्थानिवत्त्वे पूर्वयणादेशस्यापि नित्यत्वं स्यादित्यर्थः ॥

(उद्द्योतः) उदाहरणत्ववादी आह—भाष्ये—अनेनापीति ॥ सति स्थानिवत्त्वे इति । एवं च द्वयोरपि नित्यत्वेनोच्चारणक्रमे प्राथम्यात्पूर्वं पूर्वयणादेश एवेति भावः ॥

(प्रयोजननिराकर्तृभाष्यम्)

परयणादेशोऽपि नित्यः । कृतेऽपि पूर्वयणादेशे प्राप्नोति, अकृतेऽपि ॥

(प्रदीपः) इतर आह—परयणादेशोऽपीति ॥

(उद्द्योतः) इतरः—उदाहरणत्वखण्डनवादी ॥

(सिद्ध्युपायबाधकश्लोकवार्तिकम्)

॥ परश्चासौ व्यवस्थया ॥

(व्याख्याभाष्यम्)

व्यवस्थया चासौ परः ॥

(सिद्ध्युपायबाधकश्लोकवार्तिकम्)

॥ युगपत्संभवो नास्ति ॥

(व्याख्याभाष्यम्)

न चास्ति यौगपद्येन संभवः ॥

(प्रदीपः) स एवाह—परश्चासाविति । शब्दपरविप्रतिषेधात् स एव प्राप्नोति । एकमपि यणलक्षणं पूर्वपरविषयभेदाद्भिद्यते । एकस्य च कार्यित्वनिमित्तत्वयोर्विरोधात् परत्वेन व्यवस्था ॥

(उद्द्योतः) शब्दपरेति । उच्चारणक्रमीयप्राथम्यस्य शास्त्रेण बाध इति भावः ॥ तत्सूत्रे व्यासिन्यायेन सूत्रपाठतः शब्दतश्चोभयविधमपि परत्वं गृह्यत इति तात्पर्यम् ॥ नन्वेवं परं कार्यमित्युच्यते, तल्लक्षणभेदे स्यादत आह—एकमपीति । व्यक्तिपक्षे प्रतिलक्ष्यं लक्षणभेदादिति भावः ॥ विषयगतं पौर्वापर्यं तदवच्छिन्ने लक्षणे आरोप्यत इत्यत्र तात्पर्यम् ॥ विप्रतिषेधशास्त्रप्रवृत्तियोग्यं—न चास्ति यौगपद्येन-इति भाष्यबोधितं विरोधमुपपादयति—एकस्य चेति । प्रसङ्गे आदेशविधानादादेशसमये स्थानिनोऽसत्त्वम्, निमित्तत्वं च सत्त्वे । सत्त्वासत्त्वे चैकत्र युगपद्विरुद्धे । एवं च द्वयोर्यणोर्यौगपद्यासंभव इति भावः ॥

(सिद्ध्युपायसाधकश्लोकवार्तिकम्)

॥ बहिरङ्गेण सिध्यति ॥

(भाष्यम्)

'असिद्धं बहिरङ्गलक्षणमन्तरङ्गलक्षणे' इत्यनेन सिध्यति ॥

(उद्द्योतः) भाष्ये—बहिरङ्गेण सिध्यतीति । तेनैव 'कर्त्र्यां' इति सिध्यति, न सूत्रेणेत्यर्थः ॥ एवं च शब्दतः परत्वमादाय विप्रतिषेधसूत्रस्य नैव प्रवृत्तिरिति तात्पर्यम् ॥

(सूत्रप्रयोजनवादिभाष्यम्)

एवं तर्हि योऽत्रोदात्तयण् तदाश्रयः स्वरो भविष्यति ॥

(उद्द्योतः) उदाहरणवादी अन्तरङ्गपरिभाषाऽऽश्रयणं विनाऽपि स्वरं साधयति—भाष्ये - एवं तर्हीति ॥

(इष्टानुपपत्तिभाष्यम्)

ईकारयणा व्यवहितत्वान्न प्राप्नोति ॥

(इष्टोपपत्तिभाष्यम्)

'स्वरविधौ व्यञ्जनमविद्यमानवद्भवति' इति नास्ति व्यवधानम् ॥

(उद्द्योतः) स्वरविधाविति । अस्य स्वरोद्देश्यकविधित्वादिति भावः ॥

(असिद्धपरिभाषावादिभाष्यम्)

सा तर्हि एषा परिभाषा कर्तव्या ॥

(स्थानिवद्भाववादिभाष्यम्)

ननु चेयमपि कर्तव्या—'असिद्धं बहिरङ्गलक्षणमन्तरङ्गलक्षणे' इति ॥

(असिद्धपरिभाषावादिभाष्यम्)

बहुप्रयोजनैषा परिभाषा । अवश्यमेषा कर्तव्या ॥

(उद्द्योतः) अवश्यमेवेति । एवं च तयैव सिद्धत्वाच्चैतदस्योदाहरणमिति भावः ॥

(असिद्धपरिभाषावादिनो लाघवभाष्यम्)

सा चाप्येषा लोकतः सिद्धा ॥

कथम् ?

प्रत्यङ्गवर्ती लोको लक्ष्यते । तद्यथा—पुरुषोऽयं प्रातरुत्थाय यान्यस्य प्रतिशरीरं कार्याणि तानि तावत्करोति, ततः सुहृदाम्, ततः संबन्धिनाम् ॥ प्रातिपदिकं चाप्युपदिष्टं सामान्यभूतेऽर्थे वर्तते । सामान्ये वर्तमानस्य व्यक्तिरुपजायते । व्यक्तस्य सतो लिङ्गसंख्याभ्यामन्वितस्य बाह्येनार्थेन योगो भवति । यथैव चाऽऽनुपूर्व्याऽर्थानां प्रादुर्भावस्तथैव शब्दानामपि । तद्वत्कार्यैरपि भवितव्यम् ॥

(प्रदीपः) **प्रत्यङ्गवर्तीति** । प्रत्यासन्नवाची प्रत्यङ्गशब्दः । अङ्गशब्देन प्रत्यासत्तिर्लक्ष्यते, अङ्गानां प्रत्यासन्नत्वात् । अङ्गमङ्गं प्रति–प्रत्यङ्गमित्यव्ययीभावः ॥ **प्रतिशरीरमिति** । शरीरस्य भोगायतनत्वात् ॥ **ततः सुहृदामिति** । सौहार्दस्यासत्तिहेतुत्वात् ॥ **ततः संबन्धिनामिति** । अवश्यकर्तव्यत्वात् ॥ **सामान्यभूत इति** । नित्येऽपि शब्दार्थसंबन्धे अक्रमेऽप्यर्थप्रतिपादने उपायभावेनासन्तमपि क्रमं प्रकृत्याद्यर्थं चाश्रित्योपेयव्यवस्थापनात् । तत्र **नागृहीतविशेषणा विशेष्ये बुद्धिः**–इत्यादौ सामान्यमभिधीयते । ततस्तदनुरक्ता द्रव्ये प्रतीतिः । लिङ्गसंख्याशक्तीनां चाश्रयो द्रव्यमिति तत्पूर्वमभिधातव्यम् । ततः संख्याऽपेक्षया लिङ्गं समासन्नमिति तदभिधीयते । द्व्यादिसंख्या हि वस्त्वन्तरापेक्षोपजायते । एकत्वसंख्याऽपि वस्त्वन्तरापेक्षांद्वित्वादिव्यवच्छेदं करोतीति बहिरङ्गा । साऽपि सजातीयपदार्थापेक्षत्वादन्तरङ्गा । कर्मादीनि तु विजातीयक्रियापेक्षणाद्बहिरङ्गाणीति न्यायप्राप्तः क्रमः ॥ **बाह्येनेति** । कर्मत्वादिना । तद्धि क्रियापेक्षणात् बाह्यम् ॥

(उद्योतः) **सा चाप्येषेति** । प्रकृतोदाहरणविषयः पूर्वनिमित्तकमन्तरङ्गमित्यंशो न्यायसिद्ध इति तदनाश्रयणमशक्यमिति भावः ॥ ननु प्रत्यवयववर्ती लोकरूपोऽवयवी लक्ष्यत इति नार्थः, प्रकृतानुपयोगादित्यत आह—**प्रत्यासन्नेति** ॥ **अङ्गानामिति** । अङ्गिनं प्रतीति शेषः ॥ **अङ्गमङ्गमिति** । प्रत्यासन्नप्रत्यासन्नवर्ती तैत्कार्याभिनिविष्टो लोको दृश्यत इति भावः ॥ **प्रत्यासन्नत्वं च** प्रथमोपस्थितत्वरूपम् ॥ भाष्ये—**शरीरं प्रतीत्यन्वयः** । प्रतियोगे द्वितीया । **भोगः**–सुखादिसाक्षात्कारः ॥ **आसत्तिः**–प्रथमोपस्थितिः । युगपदुपस्थिताविदम् ॥ क्रमेणोपस्थितावपि आसत्तिवशादेव पूर्वं सुहृदामुपस्थितिरिति बोध्यम् ॥ ननु **अन्वितस्य बाह्यार्थेन योगो भवतीत्युक्तं**, शब्दार्थसंबन्धस्य नित्यत्वात्; शब्दस्य विरम्यव्यापाराभावात् युगपदेव सकलार्थप्रतीतेः क्रमाभिधानमप्यसङ्गतमित्यत आह—**नित्येऽपीति** ॥ **असन्तमपीति** । **असत्यमपीति** पाठान्तरम् । शब्दजन्यबोधे वस्तुगत्याऽसत्त्वादित्यर्थः ॥ किंतु शास्त्रवासनाकल्पितोऽयं प्रक्रियादशायां क्रमः, अर्थवदुद्देश्यकप्रातिपदिकसंज्ञोद्देश्यकङ्याद्युद्देशेन शास्त्रे स्वादिविधानादिति बोध्यम् ॥ वस्तुतः प्रकृतितदर्थाद्यप्यसत्यमेव कुतस्तत्क्रमस्य सत्यतेत्याह—**प्रकृत्याद्यर्थं चेति** । **असत्यमपी**त्यनुकृष्यते ॥ भाष्ये—**सामान्यभूतेर्थे वर्तत इति** । **वर्तनं** नाम सामान्याभिधानम् ॥ **विशेष्ये**–विशेषणविशिष्टे, तदैव विशेष्यत्वात् । विशिष्टबुद्धौ विशेषणज्ञानस्य कारणत्वादिति भावः ॥ **तदनुरक्तेति** । सामान्यस्य कार्यानर्हत्वाद्व्यक्तिस्तदाश्रयतया शब्दार्थत्वेन कल्प्यत इति भावः ॥ भाष्ये–**उपजायत** इत्यस्य बोधविषयो[१८] भवतीत्यर्थः ॥ **व्यक्तस्येति** । द्रव्यस्य सतो बुद्ध्यारूढस्येत्यर्थः ॥ **तत्पूर्वमिति** । आश्रयप्रतीत्युत्तरमेव तदाकाङ्क्षणादिति भावः ॥ **वस्त्वन्तरेति** । स्वसमवायिकारणनानावस्त्वपेक्षयेत्यर्थः ॥ एकत्वस्य तत्त्वाभावादाह—**एकत्वेति** । एवं च प्रयोजनापेक्षया साऽपि बहिरङ्गेत्यर्थः ॥ **सजातीयेति** । द्रव्यत्वेन स्वाश्रयत्वेन वा सजातीयत्वम् ॥ ननु लिङ्गादिभिरेकार्थसमवायाविशेषात्कथं शक्तेर्बाह्यत्वमत आह—**कर्मादीनि त्विति** ॥ **न्यायप्राप्तः क्रम इति** । शास्त्रकृत्कल्पितन्यायप्राप्तः प्रक्रियादशायामित्यर्थः ॥ अनेन विशिष्टबुद्धौ विशेषणज्ञानकारणत्वाद्यपि तान्त्रिककल्पितमिति सूचितम् ॥ भाष्ये–**यथैवेति** । **अर्थानां**–लिङ्गसङ्ख्याकारकाणाम् । **प्रादुर्भावः**–ज्ञानम् ॥ **शब्दानामपि**–तद्बोधकस्त्रीप्रत्ययविभक्तीनामपि । अस्य **प्रादुर्भाव** इति शेषः । **तद्वत्कार्यैरपी**त्यस्य तयैवानुपूर्व्येत्यर्थः । येन क्रमेण शब्दोपस्थितिस्तेनैव क्रमेण कार्यमिति पूर्वमीकारनिमित्तको यणिति भावः ॥ तत्र **पदस्यैव विभज्यान्वाख्याने सर्वेषां युगपत्प्राप्तावनया व्यवस्था । क्रमेणान्वाख्याने तु पूर्वप्रवृत्तिकत्वरूपमन्तरङ्गत्वं पूर्वयणादेशस्य** बोध्यम् । **असिद्धत्वं** परयणादेशस्य निमित्ताभावादप्राप्तत्वरूपं बोध्यम् । **अत एव** वाय्वोरित्यत्र नासिद्धत्वम् । एवंविधान्तरङ्गत्वस्य दृष्टान्तादिबलेन युगपत्प्राप्तिविषयत्वात् । स्पष्टं चेदं वाह ऊठ्सूत्रे कैयटे ॥ यत्त्वनया रीत्या पूर्वस्थानिकमप्यन्तरङ्गमिति । तदयुक्तम् । अन्तरङ्गशब्दार्थाभावात् । अङ्गशब्दस्य तत्र निमित्तपरत्वात् ॥

(सूत्रारम्भवादिभाष्यम्)

इमानि तर्हि प्रयोजनानि—पटयति[१९], अवधीत्, बहुखट्वकः ॥

(प्रयोजनोपपादकभाष्यम्)

पटयति, लघयति । णिचि टिलोपे कृते "अत उपधायाः" इति वृद्धिः[२१] प्राप्नोति ॥ स्थानिवद्भावान्न भवति ॥

(द्वितीयप्रयोजनोपपादनभाष्यम्)

अवधीदिति । अकारलोपे कृते "अतो हलादेर्लघोः" इति वृद्धिः प्राप्नोति ॥ स्थानिवद्भावान्न भवति ॥

(उद्योतः) **अवधीदिति** । यद्यप्यतो लोप इत्यत्रार्धधातुक इति विषयसप्तमीस्थचो यदिति सूत्रस्थभाष्यात्प्रतीयत इत्यपरनिमित्तकत्वात् कथं स्थानिवत्त्वम्, तथापि विषयसप्तमीत्वेऽपि परबुद्धिनिमित्तकत्वेन परनिमित्तत्वमस्त्येवेत्याशयः ॥ [३]स्वंतन्त्रवधधातुस्तु नास्त्येव । अदन्तत्वे जनिवध्योश्चेति वधिग्रहणमपि न कर्तव्यमेवेति बोध्यम् ॥

(तृतीयप्रयोजनोपपादनभाष्यम्)

बहुखट्वक । इति "आपोऽन्यतरस्याम्" इति ह्रस्वत्वे कृते "ह्रस्वान्तेऽन्त्यात्पूर्वम्" इत्येष स्वरः प्राप्नोति ॥ स्थानिवद्भावान्न भवति ॥

(उद्द्योतः) यद्रुस्वङ्क इति—भाष्ये । यद्योर्नेन्यदुत्तरपदभूतयोस्युक्तेरिति भावः ॥

(स्थानिवद्भावप्राप्तानिष्टनिराकरणम्)

(आक्षेपभाष्यम्)

इह—वैयाकरणः सौवश्व इति य्वोः स्थानिवद्भावादायावौ प्राप्नुतस्तयोः प्रतिषेधो वक्तव्यः ॥

(समाधाने भाष्यवार्तिकम् ॥)

॥ अचः पूर्वविज्ञानादैचोः सिद्धम् ॥

(भाष्यम्)

योऽनादिष्टादचः पूर्वस्तस्य विधिं प्रति स्थानिवद्भावः । आदिष्टाच्चैषोऽचः पूर्वः ॥

किं वक्तव्यमेतत् ?

न हि

कथमनुच्यमानं गंस्यते ?

अच इति पञ्चमी । अचः पूर्वस्य ॥

(प्रदीपः) **योऽनादिष्टादिति** । अकृत एवादेशे अचो यः पूर्व इत्यर्थः ॥ अजपेक्षया पूर्वत्वस्येहाश्रयणात् । आदेशनं-आदिष्टं, तत् यस्य नास्ति सोऽनादिष्टः ॥

(उद्द्योतः) नन्वादेशस्य सत्त्वात् 'अनादिष्टात्' इत्यनुचितमत आह—अकृत एवेति । उपलक्षणमेतदिति भावः ॥ ननु सूत्रे 'अनादिष्टात्' इत्येतदनुपादानात्कथमेतल्लभ्योऽत आह—अजपेक्षयेति । लक्ष्यानुरोधादिति भावः ॥ कर्मणि क्ते अनादिश्यमानादित्यर्थः स्यादत आह—आदेशनमिति । यद्रुमीशो निष्ठेति पूर्वनिपातस्तु न, तत्प्रकरणानित्यत्वात् ॥

(आक्षेपभाष्यम्)

यद्येवमादेशोऽविशेषितो भवति ॥

(प्रदीपः) **आदेश इति** । ततश्च हलादेशोऽपि स्थानिवत् स्यात् ॥

(आक्षेपबाधकभाष्यम्)

आदेशश्च विशेषितः ॥

कथम् ?

न ब्रूमः—यत् षष्ठीनिर्दिष्टमज्ग्रहणं तत्पञ्चमीनिर्दिष्टं कर्तव्यम्—इति ॥

किं तर्हि अन्यत्कर्तव्यम् ?

अन्यच्च न कर्तव्यम् । यदेवादः षष्ठीनिर्दिष्टमज्ग्रहणम्, तस्य दिक्शब्दैर्योगे पञ्चमी भवति—अजादेशः परनिमित्तकः पूर्वस्य विधिं प्रति स्थानिवद्भवति ।

कुतः पूर्वस्य ?

अच इति ॥ तद्यथा—आदेशः प्रथमानिर्दिष्टः, तस्य दिक्शब्दैर्योगे पञ्चमी भवति—अजादेशः परनिमित्तकः पूर्वस्य विधिं प्रति स्थानिवद्भवति ।

कुतः पूर्वस्य ?

आदेशादिति ॥

(प्रदीपः) **यदेवाद इति** । सादृश्यादेवमुक्तं, शब्दान्तरमेव तु पञ्चम्यन्तमपेक्ष्यते ॥ **तद्यथेति** । यथाऽऽदेशापेक्षया पूर्वत्वे आश्रीयमाणे विभक्तिविपरिणामस्तथाऽजपेक्षयाऽपीत्यर्थः ॥ धिन्वन्तीत्यत्र तु उकारात् पूर्वं यदङ्गं तस्मान्निमित्तत्वेनाश्रिताद्विधिरिति सिद्धः स्थानिवद्भावः ॥ वैयाकरण इत्यत्र तु तन्न भवति । न ह्यीकारात् पूर्वो यो वकारः स कश्चिन्निमित्तत्वेनाश्रितः ॥

(उद्द्योतः) नन्वचः पूर्वत्वविधाने आदेशेन पूर्वत्वस्याविशेषणात् 'तद्यथा' इत्ययुक्तमत आह—यथेति । परमतेन दृष्टान्त इति भावः ॥ पूर्वविध्यभावादाह—धिन्वन्तीति । अन्यथेष्टापत्तिरिति भावः ॥ अत्र यद्वक्तव्यम् तदुक्तम् ॥ पञ्चमीसमासाश्रयेण वैयाकरणे दोषमाशङ्क्याह—वैयाकरणेति । ऐज्विधानसामर्थ्यात्तत्र न भवति स्थानिवत्त्वमिति परे ॥

(भावाभावातिदेशसाधनम्)

(११५ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ तत्रादेशलक्षणप्रतिषेधः ॥ * ॥

(भाष्यम्)

तत्रादेशलक्षणं कार्यं प्राप्नोति, तस्य प्रतिषेधो वक्तव्यः । वाय्वोः । अध्वर्य्वोः । "लोपो व्योर्वलि" इति यलोपः प्राप्नोति ॥

(प्रदीपः) **तत्रेति** । अतिदेशेन पराश्रयं कार्यं प्राप्यते, न तु स्वाश्रयं निवर्त्यते । भाष्यकारेण तु विधिग्रहणात् स्वाश्रयकार्याभावः साधितः ॥

(उद्द्योतः) विधिग्रहणं स्वाश्रयनिवृत्त्यर्थमित्युक्तत्वात्तत्रादेशलक्षणेत्यसङ्गतमत आह—भाष्यकारेण त्विति । इदं वार्तिकमिति न विरोध इति भावः ॥

(वार्तिकैकदेशेन समाधानम् ।)

॥ असिद्धवचनात्सिद्धम् ॥

(भाष्यम्)

अजादेशः परनिमित्तकः पूर्वस्य विधिं प्रति असिद्धो भवतीति वक्तव्यम् ॥

(११६ समाधानबाधकाक्षेपवार्तिकम् ॥ २ ॥)

॥ * ॥ असिद्धवचनात्सिद्धमिति चेदुत्सर्गलक्षणानामनुदेशः ॥ * ॥

(भाष्यम्)

असिद्धवचनात्सिद्धमिति चेदुत्सर्गलक्षणानामनुदेशः कर्तव्यः । पट्व्या-मृद्व्येति ॥

(प्रदीपः) उत्सर्गेति । उत्सर्गः-स्थानी, स ह्यादेशेनापवादेनेव निवर्त्यते ॥ नन्वीकारयणोऽसिद्धत्वात् विभक्तावेव यण् भविष्यति ॥ नैतदस्ति । पूर्वविधावसिद्धत्वमुच्यते, न स्वानन्तर्ये लौकिके यथा प्रयोग इति नास्ति विभक्तेरानन्तर्यम् ॥ अनुदेश इति । अतिदेश इत्यर्थः ॥

(उद्योतः) निवर्त्यत इति । उत्सृज्यते=निवर्त्यते-इत्युत्सर्ग इति भावः ॥ न स्वानन्तर्ये इति ॥ पूर्वविधावित्युक्तेः शास्त्रीये कार्येऽतिदेशप्रवृत्तिरिति भावः ॥ प्रयोगे इति । उच्चारणे-इत्यर्थः ॥

(समाधानसाधकभाष्यम्)

ननु चैतदप्यसिद्धवचनात्सिद्धम् ॥

(प्रदीपः) ननु चैतदपीति । शास्त्रासिद्धत्वाश्रयणात् ॥

(३३७ समाधानबाधकाक्षेपवार्तिकम् ॥ ३ ॥)

॥ * ॥ असिद्धवचनात्सिद्धमिति चेन्नान्यस्यासिद्धवचनादन्यस्य भावः ॥ * ॥

(भाष्यम्)

असिद्धवचनात्सिद्धमिति चेत् । तन्न ॥

किं कारणम्?

'नान्यस्यासिद्धवचनादन्यस्य भावः' । न ह्यन्यस्यासिद्धत्वादन्यस्य प्रादुर्भावो भवति । तद्यथा—न हि देवदत्तस्य हन्तरि हते देवदत्तस्य प्रादुर्भावो भवति ॥

(प्रदीपः) नान्यस्येति । कार्यासिद्धत्वाश्रयमेतत् ॥

(उद्योतः) भाष्ये-नहि देवदत्तस्येति । हतेऽपि न जीवनं चेद्, किं वक्तव्यं तदारोपे-इत्यर्थः ॥

(३३८ आक्षेपोपसंहारवार्तिकम् ॥ ४ ॥)

॥ * ॥ तस्मात्स्थानिवद्वचनम् ॥ * ॥

(भाष्यम्)

तस्मात्स्थानिवद्भावो वक्तव्यः, असिद्धत्वं च । पट्व्या मृद्व्येत्यत्र स्थानिवद्भावो वक्तव्यः । वाय्वोरध्वर्य्वोरित्यत्रासिद्धत्वम् ॥

(परिहारवार्तिकसारकभाष्यम्)

॥ उक्तं वा ॥

किमुक्तम्?

स्थानिवद्वचनानर्थक्यं शास्त्रासिद्धत्वात् इति

(प्रदीपः) उक्तं वेति । शास्त्रासिद्धत्वमाश्रयणीयमित्यर्थः ॥

(उद्योतः) उक्तं वेति । पूरवतुकोरित्यत्र ॥ वचनद्वयकरणापेक्षो विकल्पः ॥

(समाधानबाधकभाष्यम्)

विषम उपन्यासः । युक्तं तत्र यदेकादेशशास्त्रं तुक्शास्त्रे असिद्धं स्यात्, अन्यदन्यस्मिन् ॥ इह पुनरयुक्तम् । कथं हि तदेव नाम तस्मिन्नसिद्धं स्यात्?

(प्रदीपः) तदेवेति । सकृत्पाठापेक्षयैतदुच्यते । विषयभेदात्तु भेदाश्रयणादसिद्धत्वमाश्रीयते ॥

(उद्योतः) तदेव नामेति । इको यणचीत्येतदेव इको यणचीत्यस्मिन्नित्यर्थः ॥

(समाधानसाधकभाष्यम्)

तदेव चापि तस्मिन्नसिद्धं भवति ॥ वक्ष्यति ह्याचार्यः-*चिणो लुकि तग्रहणानर्थक्यं संघातस्याप्रत्ययत्वात्तलोपस्य चासिद्धत्वात्* इति । चिणो लुक् चिणो लुक्येवासिद्धो भवति ॥

(उद्योतः) चिणो लुकि तग्रहणाभावे किं' ततरामूशब्दस्य लुगुच्यते, उत तेषां क्रमेण । नाद्यः, सङ्घातस्याप्रत्ययत्वात् । नान्त्य इत्याह—भाष्ये—तलोपस्य चेति ॥

(समाधानश्लोकवार्तिकम् ॥)

॥ * ॥ काममतिदिश्यतां वा
सच्चासच्चापि नेह भारोऽस्ति ॥
कल्प्यो हि वाक्यशेषो
वाक्यं वक्तर्यधीनं हि ॥ * ॥

(भाष्यम्)

अथवा वतिनिर्देशोऽयम् । कामचारश्च वतिनिर्देशे वाक्यशेषं समर्थयितुम् । तद्यथा—"उशीनरवन्मद्रेषु यवाः" सन्ति, न सन्तीति ॥ "मातृवदस्याः कलाः" सन्ति, न सन्तीति ॥ एवमिहापि स्थानिवद्भवति, स्थानिवन्न भवति-इति वाक्यशेषं समर्थयिष्यामहे ।

इह तावत्पट्व्या-मृद्व्येति । यथा स्थानिनि यणादेशो भवति, एवमादेशेऽपि भवतीति ॥

इहेदानीं वाय्वोरध्वर्य्वोरिति । यथा स्थानिनि यलोपो न भवति, एवमादेशेऽपि न भवतीति ॥

(प्रदीपः) नेह भारोऽस्तीति । न ह्यभावातिदेशेऽधिकं सूत्रं पठनीयं, विधिशब्दं चान्तरेण सिध्यति ॥ अधीनमिति । अध्युत्तरपदात् खविधानादव्युत्पन्न आयत्तार्थवृत्तिरधीनशब्दः ॥ तद्यथेति । येनोपमाने यवानां सत्ताऽवगता, सः 'सन्ति' इति वाक्यशेषं कल्पयति । असत्ताऽवगतौ तु 'न सन्ति' इति ॥ एवमस्यापि लक्षणस्य प्रतिलक्ष्यं भेदात् क्वचिद्भावोऽतिदिश्यते, क्वचिदभावः ॥

(उद्योतः) एवमसिद्धवचनमात्रेण निर्वाहमुक्त्वा सूत्रकृतं स्थानिवत्त्वं समर्थयति—काममिति । न ह्यभावेति । इहेत्यस्य सूत्रे-इत्यर्थ इति भावः ॥ ननु पूर्वमस्यार्थस्य विधिशब्देन साधितत्वात् कथं तत्करणरूपो न भार इत्यत आह—विधिशब्दं चेति ॥ अध्याहारमात्रेणेति भावः ॥ भाष्ये—एवमादेशेपि न भवतीति । आदेशनिमित्तकोऽपीत्यर्थः ॥

(पूर्वशब्दार्थनिर्णयः)

(आक्षेपभाष्यम्)

किं पुनरनन्तरस्य विधिं प्रति स्थानिवद्भावः, आहोस्वित्पूर्वमात्रस्य ?

(प्रदीपः) **किं पुनरिति** । 'अमीषां ब्राह्मणानामन्त्यात्पूर्वमानय' इत्यत्रानन्तरे पूर्वशब्दो दृष्टः, 'मथुरायाः पूर्वं पाटलिपुत्रम्' इति व्यवहिते-इति **प्रश्नः** ॥ तत्र यदा विषयभेदाल्लक्षणं भिद्यते तदा यादृशं यत्र पूर्वत्वं संभवति तादृशं तत्राश्रीयते-इति व्यवहितस्यापि ग्रहणम् । यदा त्वेकमेव लक्षणं, तदा किमित्यव्यवहितसंभवे व्यवहितमाश्रीयत इति अनन्तरस्यैव ग्रहणेन भाव्यम् ॥

(उद्योतः) यद्यपि व्यवहितेऽपि पूर्वशब्दो वर्तत इति भाष्यकृता पूर्वमेवोक्तम्, तथापि तदर्थप्रतिपादकवार्तिकमवतारयितुं पृच्छति—भाष्ये-किं **पुनरिति** ॥ **अव्यवहितसंभवे इति** । छन्दसि परेऽपि-व्यवहिताश्चेत्यनेन पूर्वपरशब्दयोरव्यवहितार्थे मुख्यत्वबोधनादिति भावः ॥ **तस्मिन्निति** सूत्रे निर्दिष्टग्रहणाद्व्यवहिताव्यवहितसाधारणे पूर्वशब्दस्य शक्तिः । अन्त्यात्पूर्वमानयेत्यादौ तु तात्पर्यानुपपत्त्या विशेषे लक्षणा, छन्दसि परेऽपीत्यादौ तु पराङ्गविकलायास्तस्मिन्निति परिभाषाया उपस्थितेरव्यवधानांशलाभः । इह तु स्वरग्रहणाल्लिङ्गात्तदनुपस्थितिरिति तत्त्वम् ॥

(भाष्यम्)

कश्चात्र विशेषः ?

(३३९ अनन्तरग्रहणदूषणवार्तिकम् ॥ १ ॥)

॥*॥ अनन्तरस्येति चेदेकाननुदात्तद्विगुस्वरगतिनिघातेषूपसंख्यानम् ॥ * ॥

(भाष्यम्)

अनन्तरस्येति चेदेकाननुदात्तद्विगुस्वरगतिनिघातेषूपसंख्यानं कर्तव्यम् ॥

एकाननुदात्त । लुनीह्यत्र, पुनीह्यत्र-इति । "अनुदात्तं पदमेकवर्जम्" इत्येष स्वरो न प्राप्नोति ॥

(प्रदीपः) **लुनीह्यत्रेति** । ह्रेरपित्त्वादुदात्तत्वम्, तत्र यणादेशे कृते उदात्तस्याभावाद्वक्ष्यमाणस्वरो न स्यात् । स्थानिवद्भावात्तु यथा स्थानिनि स्वरो भवति एवमादेशेऽपि सिद्धः स्वरः॥

(उद्योतः) भाष्ये—एकाननुदात्तशब्देन तत्प्रयुक्तः शेषनिघातः ॥ **उदात्तत्वमिति** । प्रत्ययस्वरेण ॥

(उदाहरणभाष्यम्)

द्विगुस्वर । पञ्चारत्न्यः, दशारत्न्यः । "इगन्तकाल—" इत्येष स्वरो न प्राप्नोति ॥

(प्रदीपः) **पञ्चारत्न्य, इति** । जसादिषु छन्दो वा वचनं प्राङ् णौ चङ्युपधायाः-इति जसि चेति गुणश्छन्दसि विकल्पितत्वान्न भवति । यणि कृते इगन्तत्वाभावात् पूर्वपदप्रकृतिस्वराप्रसङ्गः ॥

(उदाहरणभाष्यम्)

गतिनिघातः । यत्प्रलुनीह्यत्र, यत्प्रपुनीह्यत्र-इति ॥ "तिङि चोदात्तवति" इत्येष स्वरो न प्राप्नोति ॥

(प्रदीपः) **यत्प्रलुनीह्यत्रेति** । यच्छब्दप्रयोगो निघातप्रतिषेधार्थः । तत्र यणि कृते उदात्तवत्त्वाभावाद्गतिनिघाताप्रसङ्गः । एतच्च सर्वमनाश्रित्यान्तरङ्गबहिरङ्गभावमुक्तम् ॥

(उद्योतः) **निघातप्रतिषेधेति** । **निपातैर्यद्यदीत्यनेनेति** भावः ॥ **अनाश्रित्येति** । पदसंस्कारे वाक्यसंस्कारे वा यणो वर्णाश्रयत्वेनान्तरङ्गत्वमित्यन्ये ॥

(द्वितीयपक्षाङ्गीकारभाष्यम्)

अस्तु तर्हि पूर्वमात्रस्य ॥

(पूर्वमात्रग्रहणदूषणभाष्यवार्तिकम्)

॥ पूर्वमात्रस्येति चेदुपधाह्रस्वत्वं वक्तव्यम् ॥

(भाष्यम्)

वादितवन्तं प्रयोजितवान्—अवीवदद्वीणां परिवादकेन ॥

किं पुनः कारणं न सिध्यति ?

योऽसौ णौ णिर्लुप्यते तस्य स्थानिवद्भावात् ह्रस्वत्वं न प्राप्नोति ॥

(३४० दूषणान्तरवार्तिकम् ॥ २ ॥)

॥ * ॥ गुरुसंज्ञा च ॥ * ॥

(भाष्यम्)

गुरुसंज्ञा च न सिध्यति । श्लेष्मा३घ्न । पित्ता३घ्न । दा३ध्यश्व । मा३ध्वश्व । "हलोऽनन्तराः संयोगः" इति संयोगसंज्ञा, "संयोगे गुरु" इति गुरुसंज्ञा, "गुरोरनृतः" इति प्लुतो न प्राप्नोति ॥

(प्रदीपः) **श्लेष्मा ३ घ्नेति** । कार्यार्थत्वात्संयोगसंज्ञाया व्यवहितस्यात्र प्लुतविधिरिति पूर्वः पक्षः ॥

(उद्योतः) **श्लेष्मघ्ने** 'अमनुष्यकर्तृके च' इति टक् ॥ ननु संयोगत्वस्य समुदायगतत्वेन पूर्वविधित्वाभावात् कथं स्थानिवत्त्वम् ॥ किं च न संयोगसंज्ञा व्यवहितस्य विधिः । अव्यवहितस्य सत्त्वादत आह—**कार्यार्थत्वादिति** । ततश्च प्लुतद्वारा व्यवहितपूर्वविधित्वं संज्ञाया इति भावः ॥

(पूर्वमात्रवादिभाष्यम्)

ननु च यस्याप्यनन्तरस्य विधिं प्रति स्थानिवद्भावः, तस्याप्यनन्तरलक्षणो विधिः संयोगसंज्ञा विधेया ॥

(प्रदीपः) **ननु चेति** । यथोद्देशपक्षे प्रत्येकं च संयोगसंज्ञेति पक्षे आनन्तर्याश्रयेऽपि दोष इत्यर्थः ॥

(उद्योतः) ननु च उक्तहेतुना व्यवहितपूर्वविधित्वात्कथमनन्तरग्रहणे संयोगसंज्ञाया विधेयत्वमत आह—**यथोद्देशेति** । तदा कार्यपर्यालोचनं विनाऽपि 'भविष्यति किंचित्' इत्यभिसन्धिमात्रात्तत्प्रवृत्तिरित्यर्थः ॥ ननु एवमपि पूर्वपरविधित्वान्न स्थानिवत्त्वप्राप्तिरत आह—**प्रत्येकं चेति** ॥

(३४१ समाधानवार्तिकम् ॥ १ ॥)

॥*॥ न वा संयोगस्यापूर्वविधित्वात् ॥*॥

(भाष्यम्)

न वा एष दोषः ॥

किं कारणम् ?

'संयोगस्यापूर्वविधित्वात्'। न पूर्वविधिः संयोगः ॥

किं तर्हि ?

पूर्वपरविधिः संयोगः ॥

(प्रदीपः) नवेति । समुदायः संज्ञीति भावः ॥ 'पूर्वमात्रस्य' इति पक्षोऽत्र स्थितः ॥ अवीवददिति तु चङ्परनिर्ह्रासे स्थानिवत्त्वनिषेधो वक्ष्यते ॥

(उद्योतः) समुदाय इति । एवं चानन्तर्याश्रयणे यथोद्देशपक्षेऽपि न दोष इति भावः ॥ एवं च पूर्वमात्रग्रहणेऽपि 'श्लेष्मघ्ने' न दोषः, यथोद्देशाश्रयणादेव । कार्यकालपक्षेऽपि यत्प्रतिबन्धद्वारा स्थानिवत्त्वस्य संज्ञाकार्यप्रतिबन्धकत्वं तस्य पूर्वमात्रवृत्तित्व एव स्थानिवत्त्वमिति गूढतात्पर्यम् ॥ भाष्ये—किं तर्हि पूर्वपरविधिरिति । पूर्वपरविधौ स्थानिवत्त्वाभावादेव च 'आरतुः' इत्यादौ ऋच्छत्यृतामिति गुणस्य सवर्णदीर्घे न स्थानिवत्त्वमिति बोध्यम् ॥ विधिग्रहणसामर्थ्याच्चैतदर्थलाभ इत्याहुः ॥ पूर्वमात्रेति । दीर्घादिग्रहणाल्लिङ्गादिति भावः ॥

(एकादेशे स्थानिवद्भावसाधनम्)

(३४२ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ एकादेशस्योपसंख्यानम् ॥ * ॥

(भाष्यम्)

एकादेशस्योपसंख्यानं कर्तव्यम् । आयसौ, गौमतौ, चातुरौ, आनडुहौ, पादे, उदवाहे । एकादेशे कृते नुमामौ पद्भाव ऊडित्येते विधयः प्राप्नुवन्ति ॥

(प्रदीपः) एकादेशस्येति । परस्मिन्नित्येतदवधारणार्थमुपात्तम् । तथा ह्यनुपादीयमानेऽपि परस्मिन्नित्यस्मिन् परनिमित्तकस्य स्थानिवद्भावो लभ्यत एव । तत्रानेन यथा - अपरनिमित्तकस्य स्थानिवद्भावो निवार्यते - वैयाघ्रपद्यः-आदीध्ये - इति, एवं परस्मिन्नेव य आदेश इत्यवधारणादुभयनिमित्तस्याप्राप्तिरिति भावः ॥ आयसादिभ्योऽणन्तेभ्य औप्रत्यये कृते एकादेशे च तस्यादिवद्भावान्नुमामौ प्राप्नुतः । पादे - उदवाहे - इत्यत्र चावेकादेशे कृते आदिवत्त्वात् भसंज्ञायां सत्यां पद्भाव ऊठ् च प्राप्नुतः ॥

(उद्योतः) ननूभयनिमित्तत्वेऽपि परनिमित्तत्वमस्त्येवेत्यत आह—परस्मिन्निती ॥ अवधारणार्थमिति । पूर्वविधिशब्दे पूर्वशब्दस्येवास्यापि विशेषणस्यान्ययोगव्यवच्छेदफलकत्वादिति भावः ॥ लभ्यत एवेति । अविशेषात्सर्वत्र प्रवृत्त्येति भावः ॥ आयसादित्वत्र देविकाशिंशपेत्यात्त्वम् ॥ तस्यादिवद्भावादिति । ननु आदिवद्भावेन 'औ' इत्यस्य सर्वनामस्थानत्वेऽपि आयसित्यस्याङ्गत्वाभावात्कथं नुम् । 'औ' इत्यस्य सान्तादविहितत्वात् आयसित्यस्य षष्ठीनिर्दिष्टादेशत्वाभावाच्च स्थानिवत्त्वेन तस्याङ्गत्वमिति चेन्न । छिन्नपुच्छश्ववदेकदेशविकृतानन्यत्वेनाङ्गत्वप्रतीत्यव्याघातात् । भूयोऽवयवसाम्यात् । लोकन्यायसिद्धस्यानाश्रयणे बीजाभावात् । सूत्रमपि वस्त्वसाधर्म्यमावश्यकमिति दिक् ॥

(प्रत्याक्षेपभाष्यम्)

किं पुनः कारणं न सिध्यन्ति ?

(उद्योतः) भाष्ये—न सिध्यन्तीति । निवर्त्यत्वेनेत्यर्थः ॥

(प्रत्याक्षेपबाधकभाष्यवार्तिकम्)

॥ उभयनिमित्तत्वात् ॥

(भाष्यम्)

अजादेशः परनिमित्तक इत्युच्यते । उभयनिमित्तश्चायम् ॥

(प्रत्याक्षेपबाधकभाष्यवार्तिकम्)

॥ उभयादेशत्वाच्च ॥

(भाष्यम्)

अच आदेश इत्युच्यते । अचोश्चायमादेशः ॥

(प्रदीपः) अचोश्चेति । अच इति गुणत्वादेकत्वसंख्यायाः पशुना यजेतेतिवदविवक्षितत्वात् ॥

(उद्योतः) नन्वच इत्यस्य विशेषणस्यान्ययोगव्यवच्छेदकत्वेऽपि हलां व्यावृत्तिः स्यान्नाजन्तरस्येत्यत आह—गुणत्वादिति । आदेशविशेषणत्वेनेति शेषः ॥ वस्तुतोऽचोरादेशस्याच्त्वपर्याप्त्यधिकरणादेशत्वाभाव इति भाष्याशयः ॥

(आक्षेपसाधकप्रथमहेतुनिरासभाष्यम्)

नैष दोषः ॥ यत्तावदुच्यते—'उभयनिमित्तत्वात्' इति । इह यस्य ग्रामे नगरे वा अनेकं कार्यं भवति, शक्नोत्यसौ तत्रान्यतरत् व्यपदेष्टुम् । तद्यथा-'गुरुनिमित्तं वसामः' इति, 'अध्ययननिमित्तं वसामः' इति ॥

(प्रदीपः) इह यस्येति । अन्वयव्यतिरेकाभ्यां निमित्तत्वावधारणाद्भवत्येव परस्य निमित्तता । अयोगव्यवच्छेदेन परस्मिन् य आदेश इति विशेषणात् ॥

(उद्योतः) उभयनिमित्तत्वे किं परनिमित्तत्वमेव नास्तीत्युच्यते, उत परमेव निमित्तं नेति । नाद्य इत्याह—अन्वयेति ॥ नान्त्य इत्याह—अयोगेति । विशेष्यसङ्गत एवायोगव्यवच्छेदबोध इति नियमे न मानमिति भावः ॥

(आक्षेपसाधकद्वितीयहेतुनिरासभाष्यम्)

यदप्युच्यते—'उभयादेशत्वाच्च' इति । इह यो द्वयोः षष्ठीनिर्दिष्टयोः प्रसङ्गे भवति, लभतेऽसावन्यतरतो व्यपदेशम् । तद्यथा—देवदत्तस्य पुत्रः, देवदत्तायाः पुत्र इति ॥

(प्रदीपः) द्वयोरिति । वर्णनिर्देशे तावज्जातिग्रहणान्नास्ति संख्याविवक्षा, भवतु वा, तथापि न दोष इति भावः ॥

(अथ हल्च्समुदायादेशस्यानिवत्त्वाभावनिर्णयः)

(आक्षेपभाष्यम्)

अथ हलचोरादेशः स्थानिवद् भवति, उताहो न॥

(प्रदीपः) **अथ हलचोरिति** । उभयथा शास्त्रे व्यवहारदर्शनात्प्रश्नः । **उरण् रपर** इत्यत्राणनण्समुदायोऽकडादिरादेशो रपरो न भवति । **नाग्लोपीत्यत्र** त्वरराजदित्यत्र हल्कोर्लोपेऽग्लोपित्वाश्रयणादुपधाह्रस्वत्वनिषेधो भवति । अस्ति ह्यत्राकोऽदर्शनमिति ॥

(उद्द्योतः) भाष्ये–अथ हलचोरिति । अच इत्यपि परस्मिन्निति वदयोगव्यवच्छेदकम्, उतान्ययोगव्यवच्छेदकमिति प्रश्नः ॥ अत्वरराजदिति । राजानमतिक्रान्तवानित्यर्थे प्रातिपदिकाद्धात्वर्थ इति णिजिष्ठवद्भावाट्टिलोपश्चेति बोध्यम् ॥ पूर्वस्यैव विधावित्यनाश्रित्येदम् ॥

(भाष्यम्)

कश्चात्र विशेषः ?

(२४३ समुदायादेशस्थानिवत्त्वे दूषणवार्तिकम् ॥ १ ॥)

॥ * ॥ हलचोरादेशः स्थानिवदिति चेद्विंशतेस्तिलोप एकादेशः ॥ * ॥

(भाष्यम्)

हलचोरादेशः स्थानिवदिति चेद्विंशतेस्तिलोपे एकादेशो वक्तव्यः । विंशकः । विंशं शतम् ॥

(प्रदीपः) **विंशक इति । विंशतित्रिंशद्भ्यामिति** ड्वुन् ॥ **विंशमिति । शदन्तविंशतेश्चेति** डः ॥

(उद्द्योतः) भाष्ये–एकादेश इति । अतो गुण इति पररूपमित्यर्थः । यस्येति चेति तु न, तिलोपस्याभीयत्वेनासिद्धत्वादिति भावः ॥ विंशं शतमित्यस्य विंशतिरधिकाऽस्मिन्नित्यर्थः ॥ विंश इति तु प्रक्षिप्तं, शतसहस्रयोरेव डस्येष्टत्वात् ॥

(२४४ दूषणान्तरवार्तिकम् ॥ २ ॥)

॥*॥स्थूलादीनां यणादिलोपेऽवादेशः॥*॥

(भाष्यम्)

स्थूलादीनां यणादिलोपे अवादेशो वक्तव्यः । स्थवीयान्, दवीयान् ॥

(प्रदीपः) **स्थवीयानिति** । गुणलोपयोस्तुल्यकालत्वाद् गुणस्य कथमनादिष्टादचः पूर्वत्वमिति चेत् । स्थानिनोऽनादिष्टादचः पूर्वत्वात् तद्द्वारेण गुणस्यापि भविष्यतीत्यदोषः ॥ तत्र स्थानिवद्भावे सति लशब्देन व्यवधानादवादेशाप्रसङ्गः ॥

(उद्द्योतः) स्थानिनोऽनादिष्टादिति । अत्र यद्वक्तव्यं तद् न धात्विति सूत्रे स्थानिवत्सूत्रे चोक्तम् ॥

(२४५ दूषणान्तरवार्तिकम् ॥ ३ ॥)

॥*॥ केकयमित्रय्वोरियादेश एत्वम् ॥*॥

(भाष्यम्)

केकयमित्रय्वोरियादेशे एत्वं न सिध्यति । कैकेयः । मैत्रेयः । अचीत्येत्वं न सिध्यति ॥

(प्रदीपः) **कैकेय इति** । नन्वत्राज्मात्रे गुणो विधीयते न त्वजादौ । तेन योऽत्राश्रीयते नासावादेशः, यश्चादेशः समुदायो नासावाश्रीयत इति न्यायान्नास्ति दोषः ॥ नैतदस्ति । स्थानिवन्न भवतीत्यभावातिदेशाश्रयणपक्षे दोषः स्यादेव । परिहारान्तरस्याभिधास्यमानत्वाद्वैतन्नाश्रितम् ॥

(उद्द्योतः) कैकेयादौ केकयमित्रय्वित्यादिना इयादेशे आद्गुणः ॥ अत्रापि पक्षे स एवार्थ इत्यत आह—परिहारान्तरस्येति । पक्षान्तरस्येत्यर्थः ॥ एतत्–पूर्वोक्तम् ॥

(२४६ दूषणान्तरवार्तिकम् ॥ ४ ॥)

॥ * ॥ उत्तरपदलोपे च ॥ * ॥

(भाष्यम्)

उत्तरपदलोपे च दोषो भवति ॥ दध्युपसिक्ताः सक्तवो दधिसक्तवः । अचीति यणादेशः प्राप्नोति॥

(प्रदीपः) **दधिसक्तव इति । समानाधिकरणाधिकारे कस्तृतीयापूर्वपद उत्तरपदलोपश्चेति** लोपस्य परनिमित्तता ॥ यद्यप्यत्र 'पदान्तविधौ न' इति सिध्यति, तथापि परिहारान्तरस्याभिधास्यमानत्वादेतन्नोक्तम् ॥

(उद्द्योतः) लोपस्येति । समानाधिकरणेन सुपेत्यधिकाराद् परसन्निधाने जायमानत्वेन परनिमित्तत्वमित्यभिमानः ॥ वस्तुत एतावता परनिमित्तत्वे पादस्य लस्येति लोपस्य परसन्नियोगेन विधीयमानस्य परनिमित्तत्वापत्तिरितीदमपि चिन्त्यम् । परिहारान्तरस्येत्येवात्रापि समाधिरिति तत्त्वम् ॥

(२४७ आक्षेपवार्तिकम् ॥ ५ ॥)

॥ * ॥ यङ्लोपे यणियङुवङः ॥ * ॥

(भाष्यम्)

यङ्लोपे यणियङुवङो न सिध्यन्ति । चेच्यः, नेन्यः । चेक्षियः, चेक्रियः । लोलुवः, पोपुवः । अचीति यणियङुवङो न सिध्यन्ति ॥

(प्रदीपः) **चेच्य इति । ऊतोऽचीत्येतदनाश्रयणा**दुपन्यासः ॥

(पक्षान्तराश्रयणभाष्यम्)

अस्तु तर्हि न स्थानिवत् ॥

(प्रदीपः) **अस्तु तर्हीति** । अच इत्युपादानात् साक्षादेव यस्याच् स्थानित्वेनोपात्तस्तस्यैव स्थानिवद्भावः, न तु हलजादेशस्येत्यर्थः ॥

(उद्द्योतः) उपादानादिति । यद्यपि 'आगत्य' इति पतद्वारणार्थमावश्यकं तत्, तत्र हि केवलहलो लोपस्तथापि व्याख्यानादच एवादेश इत्यन्ययोगव्यवच्छेदलाभ इति बोध्यम् ॥ साक्षादेवेति । अचो यत्र स्थानषष्ठीनिर्दिष्टत्वमित्यर्थः ॥ एवं हि णिलोपस्य स्थानिवत्त्वं न स्यात् । तस्मादच एवादेशः प्रयोगे यत्रेत्यर्थेन तद्वारणमुचितम् ॥

(२४८ आक्षेपवार्तिकम् ॥ ६ ॥)

॥ * ॥ अस्थानिवत्त्वे यङ्लोपे गुणवृद्धि-

प्रतिषेधः ॥ * ॥

(भाष्यम्)

अस्थानिवत्त्वे यङ्लोपे गुणवृद्ध्योः प्रतिषेधो वक्तव्यः । लोलुवः, पोपुवः, सरीसृपः, मरीमृज इति ॥

(आक्षेपबाधकभाष्यम्)

नैष दोषः ॥ "न धातुलोप आर्धधातुके" इति प्रतिषेधो भविष्यति ॥

(इति हलचसमुदायस्य स्थानिवत्त्वाभावनिरूपणम्)

(अथ स्थान्याश्रयणानाश्रयणम्)

(आक्षेपभाष्यम्)

किं पुनराश्रीयमाणायां प्रकृतौ स्थानिवद्भवति, आहोस्विदविशेषेण ?

(प्रदीपः) किं पुनरिति । यत्र कार्ये स्थान्याश्रितः किं तत्रैव स्थानिवद्भावः, उत यत्राप्यनाश्रित इति प्रश्नः ॥

(उद्योतः) किं पुनरिति । आश्रितस्थानिककार्यमेव स्थानिवद्भावेन प्राप्यते, उत अनाश्रितस्थानिकं प्रतिबध्यतेऽपीति प्रश्नः ॥ यद्यप्ययं विचारः प्राक् कृत एव, भावाभावातिदेश इति सिद्धान्तश्च कृतः, तथापि अन्यवार्तिककारकृतवार्तिकव्याख्यानमिदमिति बोध्यम् ॥

(भाष्यम्)

कश्चात्र विशेषः ?

(३४९ द्वितीयपक्षे दूषणवार्तिकम् ॥ १ ॥)

॥ * ॥ अविशेषेण स्थानिवदिति चेल्लोपयणादेशे गुरुविधिः ॥ * ॥

(भाष्यम्)

अविशेषेण स्थानिवदिति चेल्लोपयणादेशयोर्गुरुविधिर्न सिध्यति । श्लेष्मा ३ घ्न । पित्ता ३ घ्न । दा ३ध्यश्व । मा ३ ध्वश्व । "हलोऽनन्तराः संयोगः" इति संयोगसंज्ञा, "संयोगे गुरु" इति गुरुसंज्ञा, "गुरोः—" इति प्लुतो न प्राप्नोति ॥

(प्रदीपः) गुरुविधिरिति । कार्यार्थत्वात् संयोगसंज्ञाया गुरुविधिरित्युच्यते । लोपयणादेशयोः स्थानी संयोगसंज्ञायां नाश्रीयते ॥

(उद्योतः) ननु संयोगसंज्ञेति वक्तव्ये किमुच्यते गुरुविधिरिति, अत आह—कार्येति ॥

(३५० दूषणान्तरवार्तिकम् ॥ २ ॥)

॥ * ॥ द्विर्वचनादयश्च प्रतिषेधे ॥ * ॥

(भाष्यम्)

द्विर्वचनादयश्च प्रतिषेधे वक्तव्याः । 'द्विर्वचनवरेयलोप' इति ॥

(प्रदीपः) द्विर्वचनादयश्चेति । द्विर्वचनादावपि स्थानी नाश्रीयते । अनचीति पर्युदासाश्रयणात्तत्सदृशस्य हलो द्विर्वचनादावाश्रयणं न त्वचः । एवं यलोपेऽपि । वरे त्वाकारलोपे विधीयमाने प्रकृतिराश्रितैव—अचि क्ङितीति । भाष्ये तु वरेशब्दोऽपि पठितः । तत्रायं भावः—यङ एव समुदायस्य प्रत्ययत्वं न तदवयवस्याकारस्येत्यजादौ प्रत्यय आकारलोपस्य विधानादत्राप्रसङ्ग एवेति ॥

(उद्योतः) ननु 'अचि न' इत्यर्थाद्द्विर्वचननिषेधऽस्त्येव स्थान्याश्रयणमत आह—पर्युदासेति । चिन्त्यमेतत् । वाक् वाक् इत्यादाववसाने द्वित्वानापत्तेः । हलीत्येव वक्तुं युक्तत्वाचेत्याहुः ॥ तस्मादज्भिन्नस्याश्रयणम्, न त्वच इति वक्तुं युक्तं, वागित्यादावज्भिन्नो वर्णाभाव एवेति न दोषः ॥ यङ एवेति । एवं सति पक्षद्वयेऽपि वरेग्रहणं न कार्यमित्यत्र तत्करणकथनं चिन्त्यमेव स्यात् । किं च तार्किकप्रत्ययत्वमादायापि प्रवृत्तिज्ञापनाय तदावश्यकमिति चिन्त्यम् ॥ वैरेयलोपेत्येकमेव निमित्तमित्यभिमानेन भाष्यमित्यन्ये ॥

(३५१ दूषणान्तरवार्तिकम् ॥ ३ ॥)

॥ * ॥ क्सलोपे लुग्वचनम् ॥ * ॥

(भाष्यम्)

क्सलोपे लुग्वक्तव्यः । अदुग्ध, अदुग्धाः । "लुग्वा दुहदिहलिहगुहामात्मनेपदे दन्त्ये" इति ॥

(प्रदीपः) अदुग्धेति । क्सस्य 'अलोऽन्त्यस्य' इति लोपे कृते तस्य स्थानिवद्भावात् 'झलो झलि' इति लोपो न स्यादिति लुग्वचनम् ॥ अदुह्वहीत्येवमर्थस्त्ववश्यवक्तव्यः, वकारस्याझल्त्वात् ॥

(उद्योतः) क्सस्येति । क्सस्याचीति क्सलोपे प्रकृतेऽपि लुग्वक्तव्य इति वार्तिकार्थः ॥ पक्षान्तरे तु क्सलोपेनैव सिद्धमित्यभिमानः ॥ तत्राप्यवश्यं लुग्वक्तव्य इत्याह—अदुह्वहीति ॥

(३५२ दूषणान्तरवार्तिकम् ॥ ४ ॥)

॥ * ॥ हन्तेर्घत्वम् ॥ * ॥

(भाष्यम्)

हन्तेश्च घत्वं वक्तव्यम् । घ्नन्ति - घ्नन्तु - अघ्नन् ॥

(प्रदीपः) घ्नन्तीति । अलोपस्य स्थानिवत्त्वादनन्तरो नकारो न भवतीति घत्वाप्रसङ्गः । वचनसामर्थ्यात् व्यवधानाश्रयणे तु हननादिष्वतिप्रसङ्गः ॥

(उद्योतः) (भाष्ये) घ्नन्तीत्यादि । गमहनेत्यनेनालोपः ॥ घत्वं—हो हन्तेरित्यनेन ॥

(प्रथमपक्षाश्रयणभाष्यम्)

अस्तु तर्हि-आश्रीयमाणायां प्रकृतौ - इति ॥

(३५३ प्रथमपक्षे दूषणवार्तिकम् ॥ ५ ॥)

॥ * ॥ ग्रहणेषु स्थानिवदिति चेत् जग्ध्यादिष्वादेशप्रतिषेधः ॥ * ॥

(भाष्यम्)

ग्रहणेषु स्थानिवदिति चेज्जग्ध्यादिषु आदेशस्य

प्रतिषेधो वक्तव्यः। निराद्य, समाद्य। "अदो जग्धि-र्ल्यप् ति किति" इति जग्धिभावः प्राप्नोति ॥

(प्रदीपः) निराद्येति। आद्यतेर्णिलोपे कृते एकदेशविकृतस्यानन्यत्वाददिरेवायमिति जग्धिः प्राप्नोति। न च जग्धौ णिराश्रितः। आदिग्रहणात् 'घ्यात्' इति घधादेशप्रसङ्गः ॥

(उद्योतः) भाष्ये—जग्ध्यादिष्वादेशस्येति। जग्ध्यादिषु विषयेषु आदेशस्य—अर्थात्तद्रूपस्येत्यर्थः ॥ एकदेशविकृतस्येति। अन्तरङ्गत्वाद्वृद्धौ कृतायां णिलोप इति 'आत्' इत्यस्यानादिष्टादचः पूर्वत्वमस्त्येव। ण्यल्लोपाविति तु णिच्स्थानिकत्वमादेशबाधकम्। उक्तरीत्या वा तस्य तत्त्वम् ॥

(३५४ दूषणान्तरवार्तिकम् ॥ २ ॥)

॥ * ॥ यणादेशे युलोपेत्वानुनासिकात्वप्रतिषेधः ॥ * ॥

(भाष्यम्)

यणादेशे युलोपेत्वानुनासिकात्वानां प्रतिषेधो वक्तव्यः ॥

वाय्वोः, अध्वर्य्वोः। "लोपो व्योर्वलि" इति यणादेशे लोपः प्राप्नोति ॥

उलोप। अकुर्वि-आशाम्-अकुर्व्याशाम्। "नित्यं करोतेः" "ये च" इत्युकारलोपः प्राप्नोति ॥

ईत्व। अलुनि-आशाम्-अलुन्याशाम्। "ई हल्यघोः" इतीत्वं प्राप्नोति ॥

अनुनासिकात्व। अजज्ञि-आशाम्—अजज्ञ्याशाम्। "ये विभाषा" इत्यनुनासिकात्वं प्राप्नोति ॥

(प्रदीपः) यणादेश इति। बहिरङ्गपरिभाषानाश्रयेणेतदुच्यते ॥ अजज्ञीति। 'जन जनने' इत्यस्माद् व्यत्ययेनाऽऽत्मनेपदम्। 'जनी प्रादुर्भावे' इत्यस्माद्वा श्यनश्छान्दसत्वात् श्लुः ॥

(उद्योतः) वार्तिके—युलोपेति। यकारोकारयोर्लोप इत्यर्थः। अकुर्व्याशामित्यादौ नाभ्यर्ध्दत्कारपक्षे परस्य यणादेशे तत्कार्यप्राप्तिरिति बोध्यम् ॥ बहिरङ्गेति। वाय्वोरित्यत्र यथाऽस्य न प्राप्तिस्तथोक्तम्। एवमन्यत्रापि बोध्यम् ॥ आत्मनेपदमिति। ङित्ति शेषः ॥

(३५५ आक्षेपवार्तिकम् ॥ ३ ॥)

॥ * ॥ रायात्वप्रतिषेधश्च ॥ * ॥

(भाष्यम्)

राय आत्वस्य च प्रतिषेधो वक्तव्यः। रायि-आशाम्-राय्याशाम्। "रायो हलि" इत्यात्वं प्राप्नोति ॥

(३५६ आक्षेपवार्तिकम् ॥ ४ ॥)

॥ * ॥ दीर्घे यलोपप्रतिषेधः ॥ * ॥

(भाष्यम्)

दीर्घे यलोपस्य प्रतिषेधो वक्तव्यः। सौर्ये नाम हिमवतः शृङ्गे, तद्वान्-सौर्यी हिमवानिति। सौ इत्यत्र ये दीर्घत्वे कृते ईति यलोपः प्राप्नोति ॥

(प्रदीपः) सौर्यीति। 'तेनैकदिक्' इत्यण्। ततो मत्वर्थीय इनिः। 'सौर्ये' इत्यत्र तु यलोपो न प्राप्नोति, 'यस्येति च' इत्यादौ औङः श्यां प्रतिषेध इति वचनात्। सूर्यमत्स्ययोङ्यामिति परिगणनानाश्रयेणैतदुच्यते ॥

(उद्योतः) नन्वणन्तं 'सौर्ये' इत्येवोदाहिगतामत आह—सौर्ये इत्यत्रेति ॥ यस्येत्यादाविति। आदिना सूर्यतिष्येति यलोपः ॥ श्यां—शीप्रत्यये। अल्लोपस्यासिद्धत्वं तु न, व्याश्रयत्वात् ॥

(३५७ आक्षेपवार्तिकम् ॥ ५ ॥)

॥ * ॥ अतो दीर्घे यलोपवचनम् ॥ * ॥

(भाष्यम्)

अतो दीर्घे यलोपो वक्तव्यः। गार्गीभ्यां, वात्सीभ्याम्। दीर्घे कृते "आपत्यस्य च तद्धितेऽनाति" इति प्रतिषेधः प्राप्नोति ॥

(प्रदीपः) गार्गीभ्यामिति। 'गोत्रस्त्रियाः—' इति णः। सङ्घाङ्कलक्षणेष्वित्यण् वा। 'अनाति' इति प्रसज्यप्रतिषेधाश्रयेण चोद्यम् ॥

(उद्योतः) गार्गीभ्यामित्यत्र 'गार्ग्य अ भ्यां' इति स्थिते पूर्वं सुपि चेति दीर्घे यलोपाप्राप्तिरिति बोध्यम् ॥

(आक्षेपबाधकभाष्यम्)

नैष दोषः। आश्रीयते तत्र प्रकृतिस्तद्धित इति ॥

(प्रदीपः) पर्युदासाश्रयेण तु सदृशतद्धिताश्रयेण परिहारः ॥

(उद्योतः) पर्युदासाश्रयेण त्विति। आङ्गित्वेन प्रकृत्याश्रयणात्स्थानिवत्त्वप्रवृत्त्या आङ्गित्वसत्त्वेन यलोप इति भावः ॥

(सर्वाक्षेपपरिहारभाष्यम्)

सर्वेषामेव परिहारः। उक्तं विधिग्रहणस्य प्रयोजनम्—विधिमात्रे स्थानिवद्यथा स्यात्, अनाश्रीयमाणायां प्रकृताविति ॥

(प्रदीपः) सर्वेषामिति। आश्रीयमाणायां प्रकृतावित्यस्मिन्नेव पक्षे आश्रीयमाणे विधिग्रहणादधिकाद् यत्नात्स्वाश्रयनिवृत्त्यर्थात् सिध्यतीति भावः ॥ अत एव पक्षान्तरोपन्यासः—अथवेति ॥

(द्वितीयपक्षाभ्युपगमभाष्यम्)

अथवा पुनरस्त्वविशेषेण स्थानिवदिति ॥

(आक्षेपस्मारणभाष्यम्)

ननु चोक्तम्-*अविशेषेण स्थानिवदिति चेल्लोपयणादेशे गुरुविधिर्द्विर्वचनादयश्च क्सलोपे लुग्वचनम्* हन्तेर्घत्वम् * इति ॥

(आक्षेपनिराकरणभाष्यम्)

नैष दोषः। यत्तावदुच्यते—अविशेषेण स्थानिवदिति चेल्लोपयणादेशे गुरुविधिः-इति॥ उक्तमेतत्-* न वा संयोगस्यापूर्वविधित्वात् * इति ॥

यदप्युच्यते—द्विर्वचनादयश्च प्रतिषेधे वक्तव्याः इति ॥ उच्यन्ते न्यास एव ॥

* क्सलोपे लुग्वचनम् * इति ॥ क्रियते न्यास एव ॥

* हन्तेर्घत्वम् * इति ॥ सप्तमे परिहारं वक्ष्यति ॥ अचः परस्मिन्पूर्वविधौ ॥ ५७ ॥

(प्रदीपः) न वा संयोगस्येति । संयोगसंज्ञायाः समुदायाश्रयत्वादपूर्वविधित्वम् ॥ उच्यन्त इति । अत एव लिङ्गादविशेषेण स्थानिवद्भावः ॥ क्रियत इति । अदुहत्यर्थमवश्यंकर्तव्यमिति भावः ॥ सप्तम इति । श्रुतिकृतमानन्तर्यमाश्रीयते, स्थानिवद्भावकृतं तु व्यवधानं वचनसामर्थ्यादविघातकम् ॥ ५७ ॥

(उद्योतः) संयोगसंज्ञाया इति । अस्याशय उक्तः । वस्तुतः प्लुतस्य त्रैपादिकत्वात् पूर्वत्रासिद्धे न स्थानिवदित्यनेनापि इदं सुसाधम् ॥ अत एव लिङ्गादिति । न च पुत्रमासमन्तादत्तुं शीलं यस्याः–पुत्रादिनीत्यादौ स्थानिवत्त्वान्नादिनीत्यस्याप्रवृत्तौ द्वित्वं प्राप्नोति तद्वारणाय द्विर्वचनग्रहणं कथमभावातिदेशे ज्ञापकमिति वाच्यम् । एतद्भाष्यप्रामाण्येन तस्यानभिधानात्, शीघ्रोपस्थितिकत्वेनाद्वरहितादिनीशब्दस्यैव तत्र ग्रहणाच्चेति दिक् ॥ ५७ ॥

(५३ स्थानिवद्भावनिषेधसूत्रम् ॥ १ । १ । ८ आ. ३ ॥)

न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु ॥ १ । १ । ५८ ॥

(अथ पदान्तपदार्थनिरूपणम्)

(आक्षेपभाष्यम्)

पदान्तविधिं प्रति न स्थानिवदित्युच्यते । तत्र वैतस्वानिति रुः प्राप्नोति ॥

(प्रदीपः) न पदान्त० ॥ ५८ ॥ वेतस्वानिति । भावसाधनविधिशब्दाश्रयेणोच्यते । वेतसशब्दात् कुमुदनडवेतसेभ्यो ड्मतुबिति ड्मतुपि टिलोपे कृते स्वादौ पूर्वं पदमिति पदसंज्ञायां सकारः पदान्तत्वं प्रतिपद्यत इति पदान्ततायां विधीयमानत्वात् स्थानिवत्त्वनिषेधात् रुत्वप्रसङ्गः ॥

(उद्योतः) न पदान्तद्वि० ॥ ५८ ॥ ननु स्थानिवत्त्वनिषेधं विना सस्य पदान्तत्वेनासिद्धेस्तस्य रुत्वसंपादके पदत्वे स्थानिवत्त्वस्य दुर्वारत्वात् सान्तस्य पदत्वाभावेन कथमत्र रुत्वप्राप्तिरत आह—भावेति । पदान्तेति च भावप्रधानो निर्देश इत्यपि बोध्यम् ॥ इदं चिन्त्यम्, द्विर्वचनादिसाहचर्येण पदान्तपदार्थस्य शास्त्रीयस्यैव ग्रहणौचित्यात् ॥ भाष्यं त्वेवं व्याख्येयम्—रुत्वस्य पदचरमावयवत्वेन तत्र कर्तव्ये तन्निष्पादकपदत्वे च कर्तव्ये भावसाधनविधिशब्दाश्रयणे टिलोपस्य स्थानिवत्त्वनिषेधाद्रुत्वं प्राप्नोतीत्यर्थः ॥ यद्यपि पदसंज्ञा न पदचरमावयवो नापि पदान्तस्थाने विधिः, तथापि तस्याः कार्यार्थत्वात् कार्यस्य च रुत्वस्य तत्त्वान्न दोषः । पदचरमावयवसाधकस्यापि तत्त्वेन ग्रहणमित्याशयः ॥

(समाधानभाष्यम्)

नैष दोषः । भसंज्ञाऽत्र बाधिका भविष्यति—"तसौ मत्वर्थे" इति ॥

(प्रदीपः) तसौ मत्वर्थ इति । 'तदस्मिन्नस्ति' इत्यत्रैवार्थे ड्मतुप् । न निर्वृत्तादिषु, अनभिधानादित्याश्रित्यैतदुच्यते ॥

(उद्योतः) सिद्धान्त्येकदेश्याह—भसंज्ञात्रेति । भत्वे प्राप्तस्थानिवद्भावस्यापि सान्तनिष्ठपदत्वाप्रतिबन्धद्वारा रुत्वसंपादकत्वेन भत्वस्यापि पदान्तग्रहणेन ग्रहणात्तत्रापि स्थानिवत्त्वनिषेध इति सान्तनिष्ठभत्वेन तन्निष्ठपदत्वबाध इति भावः ॥ न पदान्तसूत्रदृष्ट्या त्रिपादी तु नासिद्धा, जशादिग्रहणात् ॥ कैयटोक्तरीत्या पूर्वपक्षयोजनेऽस्यायं भावः—भत्वे स्थानिवद्भावस्य सकारनिष्ठपदान्तत्वसंपादकतया परम्परया भसंज्ञाया अपि पदान्तत्वसंपादकत्वेन पदान्तत्वमिति तस्यापि निषेध इति समानावधिकत्वाद्भत्वेन पदत्वबाध इति ॥ एवं च परम्परया पदान्तत्वसंपादकस्यापि पदान्तविधिशब्देन ग्रहणे मदुक्तरीत्यैव पूर्वपक्षयोजनाऽप्युचिता ॥ ननु ड्मतुपोऽर्थान्तरेऽपि विधानात्कथं सर्वत्र भत्वमत आह—अनभिधानादिति । मतुशब्देन प्रसिद्धत्वात् मतुप एव ग्रहणमिति भावः ॥

(पूर्वपक्ष्याक्षेपसाधकभाष्यम्)

अकारान्तमेतद्भसंज्ञां प्रति, पदसंज्ञां प्रति सकारान्तम् ॥

(प्रदीपः) अकारान्तमिति । भसंज्ञां प्रति स्थानिवत्त्वनिषेधाभावात् सकारान्तत्वाभावान्नास्ति भसंज्ञा ॥ पदान्तत्वे विधीयमाने स्थानिवत्त्वनिषेधात् सकारान्तस्य पदत्वाद्रुत्वप्रसङ्गः ॥

(उद्योतः) तत्र पूर्वपक्ष्याह—अकारान्तमेतदिति । साक्षात्परम्परया वा पदान्तकार्यप्रतिबन्धकस्य प्रापकस्य वा निषेधे परम्परा पदान्तपदे उपस्थितपदत्वद्वारिकैव नान्यद्वारिकेति भत्वे न निषेध इति सान्तत्वाभावात्तदप्राप्तिरिति भावः ॥

(सिद्धान्त्येकदेशिसमाधानभाष्यम्)

ननु चैवं विज्ञायते—यः संप्रतिपदान्त इति ॥

(प्रदीपः) ननु चेति । स्थानिवत्त्वनिषेधाद्विना यः सिद्धपदान्तः, तस्य विधौ स्थानिवत्त्वनिषेधः । यथा—कौ स्तः, कानि सन्तीति । इह तु सकारः स्थानिवत्त्वनिषेधाद्विना पदान्तत्वेनासिद्ध इति भवत्येव स्थानिवद्भाव इत्यपदान्तत्वात्सकारस्य रुत्वाभावः ॥

(उद्योतः) सिद्धान्त्येकदेश्याह—ननु चेति । अत्र पदस्योद्देश्यतयैतत्साध्यपदत्ववत्समुदायान्त्यकार्ये नायं निषेध इति पदत्वेऽपि स्थानिवत्त्वात् सान्तस्य पदत्वाभावेन रुत्वाभावः सिद्ध इति भावः ॥ तत्र किमपेक्षया संप्रति - इत्यत आह—स्थानिवत्त्वनिषेधादिति । एतत्साध्यपदत्ववतोऽत्रोद्देश्यत्वासंभवः । भावसाधनेऽपि विधेयस्य पदचरमावयवत्वं स्थानिद्वारैव वाच्यमिति स्थानिनः स्थानिवद्भावेन तत्त्वाभावे विधेयस्य सुतरां तदभाव इति भावः ॥ स्थानिवत्त्वनिषेधं

विना यः पदत्वेन सिद्धस्तस्य चरमावयवे कर्तव्य इत्यक्षरार्थः ॥ संप्रतिपदशब्देन समस्तेनान्तशब्दस्य षष्ठीतत्पुरुष इति बोध्यम् ॥ यद्यपि तस्य भाव इत्यादौ तत्साध्य-त्वप्रत्ययान्तादेरप्युद्देश्यता, तथाप्यत्र लक्ष्यानुरोधादेवमर्थकत्वमिति तात्पर्यम् ॥

(पूर्वपक्ष्याक्षेपसाधकभाष्यम्)

कर्मसाधनस्य विधिशब्दस्योपादाने एतदेवं स्यात् ॥

(उद्द्योतः) पूर्वपक्षी उक्तमाशयमजानानः संप्रतीति पदान्तस्य विशेषणं मन्यमान आह—भाष्ये—कर्मसाधनस्येति । संप्रति पदान्तस्य स्थाने विधाविति हि तदाऽर्थः ॥

(सिद्धान्त्येकदेशिभाष्यम्)

अयं च विधिशब्दोऽस्त्येव कर्मसाधनः—विधीयते–विधिरिति ॥

(पूर्वपक्ष्याक्षेपसाधकभाष्यम्)

अस्ति च भावसाधनः—विधानं–विधिरिति । तत्र भावसाधनस्य विधिशब्दस्योपादाने एष दोषो भवति ॥ इह च—ब्रह्मबन्ध्वा, ब्रह्मबन्ध्वै । धकारस्य जश्त्वं प्राप्नोति ॥

(प्रदीपः) **ब्रह्मबन्ध्वेति** । ब्रह्मबन्धुशब्दादूङ्, ऊङन्तोरेकादेश आदिवद्भावादूङ्ग्रहणेन गृह्यत इति तस्मिन् **स्वादिष्विति** पदसंज्ञायां धकारस्य पदान्तता विधेयेति स्थानिवत्त्वनिषेधाज्जश्त्वं स्यात् । भसंज्ञां तु प्रति एकादेशस्य स्थानिवत्त्वादुकारान्तमेतदिति भिन्नावधिकत्वाद्भपदसंज्ञयोर्नास्ति बाध्यबाधकभावः । यणादेशोच्चारणं चातन्त्रम्, एकादेशस्यैवोदाहरणत्वात् ॥

(उद्द्योतः) (भाष्ये) तत्र भावसाधनस्येति । कर्मसाधनत्वे हि द्विर्वचनादिभिः सामानाधिकरण्यं-पदान्तेन वैयधिकरण्यं च स्यात् । भावसाधने–पदचरमावयवद्विर्वचनादिकर्मविधाने इत्यर्थः । तत्र हि पदचरमावयवत्वेन सिद्धकर्मके विधाने इति वक्तुमशक्यम्, सिद्धत्वे विधानवैयर्थ्यात् । एवं चाकारान्तमेतदितिप्रदीपोक्तयुक्त्या पदत्व एव स्थानिवत्त्वनिषेधात्तदन्तमेव पदत्वं प्रति, भत्वे तु निषेधाभावाद् अकारान्तं भत्वं प्रति-इति स्यादेव रूपमिति भावः ॥ (भाष्ये) जश्त्वं प्राप्नोतीति । झलां जशोऽन्त इत्यस्य पदचरमावयवविधायकत्वात् । जश्ग्रहणं तु झलां जशिति जश्त्वे तन्निषेधार्थम् ॥ एकादेशस्यैवेति । अत एवोभयत्र आश्रये नेत्यनेन वक्ष्यमाणं समाधानं सङ्गच्छते ॥

(सिद्धान्त्येकदेशिप्रश्नभाष्यम्)

अस्ति पुनः किंचिद्भावसाधनस्य विधिशब्दस्योपादाने सतीष्टं संगृहीतम्, आहोस्विद्दोषान्तमेव?

(उद्द्योतः) सिद्धान्त्येकदेश्याह—अस्ति पुनरिति ॥

(पूर्वपक्षिप्रतिवाक्यभाष्यम्)

अस्तीत्याह ॥ इह—कानि सन्ति, यानि सन्ति, कौ स्तः, यौ स्त इति । योऽसौ पदान्तो यकारो वकारो वा श्रूयेत, स न श्रूयते ॥

षडिकश्चाऽपि सिद्धो भवति ॥

(प्रदीपः) **कानि सन्तीति** । पक्षद्वयसाधारणमिदं प्रयोजनम् । भावसाधनपक्षेऽपि सिध्यत्येवेति तूपन्यस्तम् ॥ **यकार इति** । यकारवकारौ विधीयमानावेव पदान्तौ भवत इत्यस्ति पदान्तताया विधानम् ॥

इदानीमसाधारणं प्रयोजनमाह—**षडिक इति** । षडङ्गुलिशब्दात् 'बह्वचो मनुष्यनाम्नष्ठज्वा-' इति ठचि कृते **ठाजादावूर्ध्वमिति** अङ्गुलिशब्दस्य लोपे **यस्येति** लोपे च षडित्ययं शब्दोऽन्तर्वर्तिन्या विभक्त्या सिद्धः पदत्वेनेति पदान्तताया अविधानान्नास्ति स्थानिवत्त्वनिषेध इत्यकारलोपस्य स्थानिवद्भावादकारान्तस्य भसंज्ञा । पदसंज्ञा त्वन्तर्वर्तिविभक्त्याश्रयेण षकारान्तस्येति सिद्धं जश्त्वम् ॥ कर्मसाधने तु एषः षकारः पदान्तत्वेन सिद्ध इति स्थानिवत्त्वनिषेधात् षकारान्तस्यैव भसंज्ञेति तुल्यावधिकया भसंज्ञया पदसंज्ञाया एकसंज्ञाधिकारात् बाधनाज्जश्त्वासिद्धिः ॥

(उद्द्योतः) पूर्वपक्ष्याह—**इह कानीति** । इह पदान्त एव यकारादिर्विधेय इति भावसाधनेऽपि सिध्यतीति भावः ॥

असाधारणमिति । भावसाधनपक्षमात्रसाध्यमित्यर्थः ॥

भाष्ये—**षडिकश्चापीति** । अत्रैकादेशाल्लोपान्तसपादसप्ताध्यायीस्थकार्यप्रवृत्तियोग्यतयाऽसिद्धत्वेन जश्त्वाप्रवृत्तिः, तदनन्तरं त्वल्लोपस्य स्थानिवत्त्वप्रसक्तिः । तत्र कर्मसाधने यस्येति लोपे इकनिमित्तभत्वेन समासान्तर्वर्तिविभक्तिनिमित्तकपदत्वस्यापि निवृत्तेः षडिकासिद्धिः ॥ न च भत्वे स्थानिवत्त्वमल्लोपस्येति न समानावधिकत्वं भत्वपदत्वयोरिति वाच्यम् । साक्षात्परम्परया वा पदान्तस्थानिकविधिप्रापकप्रतिबन्धकस्थानिवत्त्वस्य निषेधेन भत्वेऽपि तन्निषेधात् । पदान्तत्वेन सिद्धस्य विधाविस्यर्थे पदत्वस्य सिद्धत्वेन उद्धारकपरम्पराया वक्तुमशक्यत्वेनान्यद्वारिकाया अपि ग्रहणात् ॥ भावसाधनत्वे तूपस्थितपदत्वद्वारिकैव परम्परा गृह्यते-इति भत्वे निषेधाभावेन स्थानिवत्त्वादकारान्ते भत्वेऽपि षान्ते पदत्वस्याप्यबाधेन न दोष इत्याशयः ॥ कैयटे-पदान्तताया अविधानादिति । पदत्वस्याविधानेन धर्मविशिष्टत्वेनाऽपि पदान्तस्याविधानादिति भावः ॥ **सिद्ध इति** । जश्त्वे कार्ये-इति शेषः ॥

(सिद्धान्त्येकदेशिन आक्षेपभाष्यम्)

वाचिकस्तु न सिध्यति ॥

(प्रदीपः) **वाचिकस्त्विति** । चकारस्य पदान्तत्वात्कुत्वप्रसङ्गात् ॥ कथं पुनः षडिकस्य सिद्धिः । यावतोक्तं-**योऽसौ पदान्तो यकार** इति, तद्वदिहापि उकारस्य पदान्तस्य विधेयत्वात् पदान्तताया विधिरिति स्थानिवत्त्वनिषेधप्रसङ्गः ॥ नैष दोषः । पूर्वमेव जश्त्वेन डकारस्य निष्पन्नत्वादिदानीं विधिरिति भावसाधने षडिकसिद्धिः ॥ कर्मसाधने तु डकारस्य पदान्तत्वेन प्रसिद्धस्य भत्वात्पदत्वनिवृत्तौ षकाररूपापत्तिर्विधेयेति स्थानिवत्त्वनिषेधात् तुल्यावधिकया भसंज्ञया पदसंज्ञाया बाधनाज्जश्त्वनिवृत्तौ षडिकासिद्धिः ॥ न च भावसाधने षकारापत्तिर्भाव्येति शक्यते वक्तुम्, तस्या अपदान्तरूपत्वात् । पदान्तत्वे हि जश्त्वं स्यात् । न च जश्त्वविधिनिमित्तः स्थानिवत्त्वनिषेधः । यत्र स्थानिवत्त्वनिषेधाज्जश्त्वं विधीयते 'सग्धिः'

'चन्नाम्' इति, सोऽस्य विषयः । इह तु पूर्वमेव जश्त्वं कृतं, स्थानिवत्त्वनिषेधात्तु तन्निवृत्तिराशङ्क्यते । **पूर्वत्रासिद्धे न स्थानिवदित्यस्याप्ययमविषयः । न ह्यत्र पूर्वत्रासिद्धीयं किंचित्कार्यं विधेयम् ॥**

(उद्योतः) सिद्धान्त्येकदेश्याह—वाचिकस्त्विति ॥ चकारस्येति । वाचिकेऽपि वागाशीर्दत्तशब्दात् ठचि ठाजादाविति शीर्दत्तशब्दलोपे यस्येति लोपे पूर्वोदाहरणे उत्त्ववदत्रापि कुत्वापत्तिरिति भावः ॥ एवं मदुक्तरीत्या भाष्यस्य सामञ्जस्ये कथं पुनरित्यादि-न ह्यत्र पूर्वत्रासिद्धीयं किंचित्कार्यं विधेयमित्यन्तः कैयटग्रन्थश्चिन्त्यः । स्फुटार्थत्वाच्च न व्याख्यातः । वस्तुतस्तु हि—पूर्वमेव उत्त्व निष्पन्नत्वादित्यसङ्गतं, सपादसप्ताध्यायीस्थकार्यप्रवृत्तियोग्यतया तदप्राप्तेः । किंच चकाररूपापत्तिर्न शङ्कनीया । पदचरमावयवस्य द्वारमात्रस्यैव ग्रहीतुमुचितत्वाद् इत्यापूर्वम् ॥

(तटस्थभाष्यम्

अस्तु तर्हि कर्मसाधनः ॥

(सिद्धान्त्येकदेशिभाष्यम्)

यदि कर्मसाधनः, पडिको न सिध्यति ॥

(तटस्थभाष्यम्)

अस्तु तर्हि भावसाधनः ॥

(सिद्धान्त्येकदेशिभाष्यम्)

वाचिको न सिध्यति ॥

(तटस्थभाष्यम्)

वाचिकपडिकौ न संवदेते ॥

(सिद्धान्तिभाष्यम्)

कर्तव्योऽत्र यत्नः ॥

(प्रदीपः) **कर्तव्योऽत्रेति । एकाक्षरपूर्वपदानामुत्तरपदलोपो वक्तव्य इति वाचिकः सिद्धः । पडिकस्तु ठाजादाविति लोपे यस्येतिलोपे च सिद्धः ॥**

(उद्योतः) सिद्धान्त्याह—कर्तव्योऽत्रेति । पञ्चमे वक्ष्यमाणं यत्नं दर्शयति—एकेति । तथा चाल्लादेशस्याद्वाचिके भत्वेऽपि न स्थानिवत्त्वमिति भावः ॥ एवं च भावसाधनपक्षोऽत्र स्थितः ॥

(आक्षेपभाष्यम्)

कथं—ब्रह्मबन्ध्वा-ब्रह्मबन्ध्वै ?

(उद्योतः) पूर्वपक्ष्याह—कथं ब्रह्मबन्ध्वेति ॥

(समाधानभाष्यम्)

उभयत आश्रयणे नान्तादिवदिति ॥

(प्रदीपः) **उभयत इति ।** यस्मात् स्वादिविधिस्तस्वादौ पदमिति पूर्वपरोभयाश्रयणम् ॥

(उद्योतः) सिद्धान्त्येकदेशी उक्तमपि यः संप्रतिपदान्त इत्येवंरूपं सिद्धान्तं परेणागृहीतत्वात्पक्षानुरूपवलिन्यायेनाह—उभयत इति ॥ तद्याचष्टे—यस्मात्स्वादिविधिरिति । अत एवात्र नैकदेशविकृतन्यायेन धान्तस्य पदत्वसंभावना, उकारान्तादूङ्विधानेनाक्तपरिमाणसंज्ञात्वेन दुर्लभत्वात् । उभयत आश्रयणे इत्यस्यैकदेशिमतत्वाच्च ॥ एतच्चान्तादिवत्सूत्रे वक्ष्यते ॥

(आक्षेपभाष्यम्)

कथं वेतस्वान् ?

(उद्योतः) पूर्वपक्ष्याह—कथं वेतस्वानिति ॥

(समाधानभाष्यम्)

नैवं विज्ञायते—पदस्यान्तः-पदान्तः, पदान्तविधिं प्रतीति ॥

कथं तर्हि ?

पदे अन्तः-पदान्तः, पदान्तविधिं प्रतीति ॥

(प्रदीपः) **पदे अन्त इति ।** न च ड्मतुप्प्रत्ययः पदम् । एवं पडिके-इकप्रत्ययो न पदमिति नास्ति स्थानिवत्त्वनिषेधः ॥

(उद्योतः) अथ 'वेतस्वान्' इत्येवंजातीयकानामेतदनुदाहरणत्वमेवेति बोधयितुं वास्तवं सिद्धान्तमाह—नैवमिति ॥ तद्याचष्टे—न च ड्मतुबिति । एवं ब्रह्मबन्धूशब्दे ऊकारो न पदमिति बोध्यम् ॥ नन्विदमयुक्तं गतिकारकोपपदानां सुबुत्पत्तेः पूर्वं समासे असुबन्तत्वेन, सुबन्तेन समासे-उत्तरपदत्वे चेति प्रत्ययलक्षणनिषेधेन चोत्तरस्यापदत्वात् 'गोचा' इत्यादावल्लोपस्य स्थानिवत्त्वेनावडापत्तेरिति चेत् न; उत्तरपदस्य कार्यित्वे एव प्रत्यासत्त्या तन्निषेधप्रवृत्तेः । अत्र चेदं भाष्यमपि मानम् । सुबुत्पत्तेः पूर्वं समासस्य नैवंविषयेऽनित्यत्वाच्च प्रवृत्तिरिति भावः ॥ एवं च विग्रहद्वयप्रदर्शनेन पदचरमावयवे कर्तव्ये परपदस्याजादेश एव न स्थानिवदिति भाष्ये ध्वनितम् । कानि सन्तीत्याद्येवोदाहरणम् । एवं च पूर्वसूत्रे अपरविधाविति प्रघट्टकस्थकैयटग्रन्थो भोभगो इति सूत्रस्थकैयटग्रन्थश्च चिन्त्य एव ॥ एवं 'पडिके' इत्याद्यपि चिन्त्यम्, इकस्य पदत्वाभावेऽपि अङ्गुलिशब्दाकारयोर्लोपे तस्य स्थानिवद्भावेन पदत्वात्सन्निपन्नस्य विधित्वेनादोषादिति दिक् ॥

(समाधानान्तरभाष्यम्)

अथवा यथैवान्यान्यपि पदकार्याण्युपप्लवन्ते-रुत्वं जश्त्वं च । एवमिदमपि पदकार्यमुपप्लोष्यते ॥

किम् ?

भसंज्ञा नाम ॥

(प्रदीपः) **यथैवेति । यचि भमित्यत्र तसौ मत्वर्थे** इत्यत्र च 'पदं' इति वर्तते । तेन पदं सन् भसंज्ञं भवतीति लब्धे पदत्वे तन्निबन्धनरुत्वप्रतिबन्धार्था भसंज्ञा तद्विषयत्वात् पदान्तविधिरिति स्थानिवत्त्वनिषेधात् भत्वाद्रुत्वाभावः सिद्धः ॥

(उद्योतः) भाष्ये—पदस्यान्त इति पक्षे पूर्वपक्ष्यभिमते 'एकपदस्याजादेशस्य स्थानिवत्त्वनिषेधेऽपि न दोषः' इति प्रौढ्या प्रतिपादयितुं भसंज्ञाऽत्र बाधिका भविष्यतीति स्वोक्तेरेकदेशी आशयमाह—अथवेति । यैः संप्रति पदान्त इत्येतत्तु न शब्दमर्यादालभ्यमिति भावः ॥ अस्य पक्षस्य कैयटोक्तव्याख्या चिन्त्या, तावताऽपि भसंज्ञायाः पदान्तविधित्वानुपपादनात् । किंच यथा कारकाधिकारे 'कारकं सत्कर्म' इति व्याख्यानेन तयोः संज्ञयोः समावेश उक्तस्तथाऽत्रापि स्यात् । न हि भत्वपदत्वयोः समावेश इष्टः । तस्मादेवं व्याख्येयम्—यथा रुत्वजश्त्वादीनां साक्षात्प्रापकः प्रतिबन्धको वा स्थानिवद्भावः प्रतिषिध्यते, तथा भसंज्ञाविषयातिदेशस्यापि परम्परया तत्वात् निषेधः—इति ॥ यथैवान्यानि पदकार्याणि—पदचरमाव-

पदकार्याणि रुत्वजश्त्वादीनि तत्प्रापकपदसंज्ञारूपं चात्र सूत्रे उपलक्ष्यन्ते—पदान्तविधिशब्देन गृह्यन्ते, पदचरमावयवप्रापकत्वापि तत्त्वेन गृह्यते । एवमिदमपि—भसंज्ञारूपमपि पदकार्य—परम्परया पदचरमावयवप्रापकं प्रतिबन्धकं वा पदचरमावयवत्वेन गृह्यते इत्यर्थः ॥ अयं भावः—यथा पदान्तपदे उपस्थितत्वात्पदत्वद्वारिका परम्परा गृह्यते तथा पदत्वबाधकतया भत्वस्यापि प्रत्यासन्नत्वेन तद्द्वाराऽपि पदचरमावयवविषयस्थानिवत्त्वप्रतिषेध इति ॥ पक्षिके तु यथा बाजादिवचनात्सिद्धमिति द्वितीयादच ऊर्ध्वं लोपविधायकवचनप्रामाण्यात्तद्विषये न भत्वद्वारा पदचरमावयवसंपादकस्थानिवत्त्वप्रतिषेध इति न दोषः । वार्तिके त्वेवं न दोषः, उत्तरपदलोपविधानात् । पैक्षमे चेदमुपपादयिष्यते ॥ एवं चामलकी तटी सारसीत्यादौ जश्त्वादिप्रसक्तिरेव नेति बोध्यम् ॥ यद्यपि पूर्वत्रासिद्धे न स्थानिवदिति निषेधोऽत्र प्राप्नोति, तथापि विधिशब्दो भावसाधनोऽन्तशब्दश्चरमावयववाचीत्यादिसिद्धान्तान्बोधयितुं, पूर्वत्रासिद्धे इत्यादावपि साक्षात्परम्परया प्रापकप्रतिबन्धकस्य निषेध इत्यादि बोधयितुं, पदेऽन्त इति सप्तमीसमासेन वेतस्वानित्यादौ न पदान्तेति निषेधवारणेन पूर्वत्रासिद्धे नेत्यत्र पदचरमावयवविधायकातिरिक्तस्यैव ग्रहणम् । एवं जश्पदेन–इति बोधयितुं चायमुपक्षेप इति बोध्यम् ॥

(वरे यलोपपदार्थनिरूपणम्)

(आक्षेपभाष्यम्)

वरे यलोपविधिं प्रति न स्थानिवद्भवतीत्युच्यते । तत्र ते "अप्सु यायावरः प्रवपेत पिण्डान्" अवर्णलोपविधिं प्रति स्थानिवत्स्यात् ॥

(उद्योतः) भाष्ये—अवर्णलोपविधिमिति । आतो लोप इटि चेत्येतं प्रतीत्यर्थः । एवं च वरेयलोपग्रहणे कृतेऽपि 'यायावरः' इत्यस्यासिद्धिरिति शङ्का ॥

(समाधानभाष्यम्)

नैष दोषः । नैवं विज्ञायते—वरे यलोपविधिं प्रति इति ॥

कथं तर्हि ?

वरे अयलोपविधिं प्रतीति ॥

किमिदं—अयलोपविधिं प्रतीति ?

अवर्णलोपविधिं प्रति, यलोपविधिं च प्रतीति ॥

(समाधानान्तरभाष्यम्)

अथवा योगविभागः करिष्यते—'वरे लुप्तं न स्थानिवत्' । ततः—'यलोपविधिं प्रति न स्थानिवत्' इति ॥

(उद्योतः) 'यातिः' इत्यस्यार्थसिद्धेः सिद्धान्तमाह—अथवेति ॥

(आक्षेपभाष्यम्)

यलोपे किमुदाहरणम् ?

(उद्योतः) यलोपे किमिति । यायावरे यलोपस्य वरे इत्यनेनैव सिद्धत्वात्प्रश्नः ॥

(समाधानभाष्यम्)

कण्डूयतेरप्रत्ययः— कण्डूरिति ॥

(प्रदीपः) कण्डूयतेरिति । क्यजन्तात् क्विप् । यगन्तात्तु क्विप् न भवति । उक्तं हि भाष्ये—**नैतेभ्यः क्विप् दृश्यत** इति ॥

(उद्योतः) कैयटे—उक्तं हीति । कण्ड्वादिभ्यो यगित्यत्र भाष्ये ॥

(समाधानबाधकभाष्यम्)

नैतदस्ति ॥ क्वौ लुप्तं न स्थानिवत् ॥

(उद्योतः) क्वौ लुप्तमिति । यद्यप्यप्रत्ययशब्देन विजप्युच्यते, तथापि तस्य कानिष्ठत्वाच दोषः ॥ किग्रहणं विचोऽप्युपलक्षणमित्यन्ये ॥

(समाधानान्तरभाष्यम्)

इदं तर्हि—सौरी बलाका ॥

(प्रदीपः) सौरीति । एकोऽणि अकारलोपो द्वितीय ईकारे, तयोः स्थानिवत्त्वाद्यकारस्योपधात्वं न स्यात् । स्थानिवत्त्वनिषेधे द्वितीययलोपस्य समानाश्रयत्वादसिद्धत्वादपि लोपस्य व्याश्रयत्वात्सिद्धत्वात् यकारस्य उपधात्वाल्लोपः सिध्यति ॥

(बाधकभाष्यम्)

नैतदस्ति । उपधात्वविधिं प्रति न स्थानिवत् ॥

(उद्योतः) उपधात्वविधिं प्रतीति । प्रत्ययविधावित्यनेनेत्येदम् ॥

(समाधानान्तरभाष्यम्)

इदं तर्हि प्रयोजनम्—आदित्यः ॥

(प्रदीपः) आदित्य इति । अदितेः स्वास्य देवतेत्यर्थे ण्यः, ततो भवादावर्थे द्वितीयो ण्यः । हलो यमां यमीति लोप इष्यते, स च स्थानिवत्त्वनिषेधात् सिध्यति ॥

(उद्योतः) तत इति । आदित्यशब्दादित्यर्थः । अदितेरपत्यमित्यर्थदेवतार्थे ण्य इति तु नोक्तं, आपत्यस्येत्यस्य प्राप्त्या पूर्वत्रासिद्ध इत्युत्तरग्रन्थासङ्गतेः । तस्मादेतस्याप्युक्तमेतदर्थाऽनेनैवेति बोध्यम् ॥

(बाधकभाष्यम्)

नैतदस्ति । पूर्वत्रासिद्धे न स्थानिवत् ॥

(प्रयोजनभाष्यम्)

इदं तर्हि—कण्डूतिः, वल्गूतिः ॥

(बाधकभाष्यम्)

नैतदस्ति प्रयोजनम् । कण्डूया, वल्गूया इति भवितव्यम् ॥

(समाधानान्तरभाष्यम्)

इदं तर्हि—कण्डूयतेः क्तिच् । ब्राह्मणकण्डूतिः, क्षत्रियकण्डूतिः ॥

(प्रदीपः) ब्राह्मणकण्डूतिरिति—षष्ठीसमासः । कर्मधारये कण्डूतिशब्दस्य पूर्वनिपातप्रसङ्गः ॥

(उद्योतः) कण्डूतिशब्दस्येति । विशेषणत्वादित्यर्थः ॥ न चात्राल्लोपस्य स्थानिवत्त्वादुवङ् यण्वा स्यादिति वाच्यम् । जाते तत्रोठा

सिद्धेः । ऊठि तु न स्थानिवत्त्वम्, अनादिष्टादचः पूर्वत्वाभावात् । अँसादेव भाष्यप्रयोगात्स्थानिद्वारकं तदाश्रयणं कान्चित्कमित्याहुः ॥

(३५८ नियमाक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ प्रतिषेधे स्वरदीर्घयलोपेषु लोपाजादेशो न स्थानिवत् ॥ * ॥

(आक्षेपभाष्यम्)

प्रतिषेधे स्वरदीर्घयलोपविधिषु लोपाजादेशो न स्थानिवद्भवतीति वक्तव्यम् ॥

(स्वरोदाहरणोपपादनभाष्यम्)

स्वर—आकर्षिकः । जिहीर्षकः ॥ यो ह्यन्य आदेशः, स्थानिवदेवासौ भवति—पञ्चारत्न्यः, दशारत्न्यः ॥ स्वर ॥

(प्रदीपः) **आकर्षिक इति ।** चरत्यर्थे आकर्षात् ष्ठलिति ष्ठल् । **यस्येति** लोपस्य स्थानिवत्त्वात् ककाराकारस्योदात्तत्वं न स्यात् । कारक इत्यादौ च **स्वरविधौ व्यञ्जनमविद्यमानवदिति** व्यञ्जनस्याविद्यमानत्वादनन्तरस्य स्वरभाजः संभवादन्यव्यवधाने न स्यात् । यत्र तु व्यवहितेऽपि पूर्वशब्दो वर्तते, तत्राप्यवध्यवधिमतोरानन्तर्यासंभवादन्तरालस्थान् सतोऽप्यर्थाननादृत्य व्यवहारः ॥ यत्र त्वानन्तर्यसंभवस्तत्र व्यवहितं नैवाश्रीयते ॥ ष्ठलो लित्करणात् व्यवधानेऽपि भविष्यतीति चेत् । आकारस्यापि पक्षे स्यादिति स्थानिवत्त्वनिषेधः कर्तव्यः ॥

(उद्योतः) ननु लितीति वचनसामर्थ्यात्स्यादेवेत्यत आह—**कारक इतीति ।** अत्र वचनं सावकाशमिति भावः ॥ **स्वरविधाविति ।** हलस्वरप्राप्तेः सत्त्वादिति भावः ॥ **अन्यव्यवधाने इति ।** अज्व्यवधाने ः ॥ 'अत्र व्यव-' इति वा पाठः । लुप्ततया तदनुच्चारणेन तदाश्रयस्यापादयितुमशक्यत्वाव 'तस्य स्याव्' इति नापादितम्, स्वविधौ स्थानिवत्त्वाभावाच्च ॥ **ननु लितीत्यत्र प्रत्ययात्पूर्वमित्यनुवृत्तेः पूर्वग्रहणस्य सत्त्वान्निर्दिष्टपरिभाषाऽनुपस्थितिः,** पूर्वशब्दश्च व्यवहितेऽपीति न दोषोऽत आह—**यत्र त्विति ।** तत्राप्यव्यवधानारोपेणैव प्रयोगः, पूर्वादीनां चाव्यवहिते एव शक्तिरिति भावः ॥ **यत्र त्विति ।** मुख्ये संभवति आरोपितग्रहणे मानाभाव इति भावः ॥ परं त्विदं **चिन्त्यम्, तस्मिन्निति** सूत्रे निर्दिष्टग्रहणात् । तस्माद् उत्तरांशविकल्पपरिभाषोपस्थितेः **प्रत्ययः परश्चेत्यादौ** दृष्टत्वादत्राप्युपस्थितिरिति तत्त्वम् ॥ **पक्षे स्यादिति । अनुदात्तं पदमिति** वचनात् 'पक्षे'इत्युक्तम् । चिकीर्षक इत्याद्यर्थमावश्यकेन निषेधेनैव सिद्धेर्लित्त्वसामर्थ्यमेव कथमिति **चिन्त्यम् ॥** भाष्ये—**पञ्चारत्न्य इति ।** अन्तरङ्गत्वेनापीदं सिद्धम् । बहुखट्वक इत्युदाहरणम् । अत्र कपि **आपोऽन्यतरस्यामिति** ह्रस्वत्वे तस्य स्थानिवत्त्वाद् ह्रस्वान्तेऽन्त्यादिति स्वरो न भवति ॥

(दीर्घोदाहरणोपपादनभाष्यम्)

दीर्घ—प्रतिदीव्ना, प्रतिदीव्ने ॥ यो ह्यन्य आदेशः, स्थानिवदेवासौ भवति—कियोः-गियोः । दीर्घ ॥

(प्रदीपः) **प्रतिदीव्नेति ।** रेफवकारान्तस्य भस्य **न भकुर्छुरामिति** दीर्घत्वनिषेध इति अत्र न प्रवर्तते ॥

(उद्योतः) प्रतिदीव्नेत्यत्र बहिरङ्गत्वेनासिद्धत्वमल्लोपस्येति न शङ्क्यं, त्रिपाद्यां तदप्रवृत्तेः ॥ वाय्वोरित्यत्रापि यथा न सा तथोक्तम् ॥ **रेफेति ।** अत्र तु नान्तं भमिति भावः ॥

(यलोपोदाहरणोपपादनभाष्यम्)

यलोप—ब्राह्मणकण्डूतिः, क्षत्रियकण्डूतिः ॥ यो ह्यन्य आदेशः, स्थानिवदेवासौ भवति—वाय्वोः, अध्वर्य्वोरिति ॥

(आक्षेपभाष्यम्)

तत्तर्हि वक्तव्यम् ॥

(समाधानभाष्यम्)

न वक्तव्यम् । इह हि लोपोऽपि प्रकृतः, आदेशोऽपि । विधिग्रहणमपि प्रकृतमनुवर्तते, दीर्घादयोऽपि प्रतिनिर्दिश्यन्ते । केवलं तत्राभिसंवन्धमात्रं कर्तव्यम्—स्वरदीर्घयलोपविधिषु लोपाजादेशो न स्थानिवदिति ॥

(प्रदीपः) **इह हि लोपोऽपीति ।** प्रकृतः—प्रस्तुतः ॥

(उद्योतः) न सूत्रान्तरवृत्तित्वं प्रकृतत्वमित्याह—**प्रस्तुत इति ॥**

(आक्षेपभाष्यम्)

आनुपूर्व्येण सन्निविष्टानां यथेष्टं संबन्धः शक्यते कर्तुम् । न चैतान्यानुपूर्व्येण सन्निविष्टानि ॥

(प्रदीपः) **आनुपूर्व्येणेति ।** तत्र पदार्थानां समन्वयावगमात् । इह तु लोपो यशब्देन संबद्धः सकृच्च श्रुतो द्विधा चास्योपयोग इष्यते । स्वरदीर्घयलोपाश्च विक्षिप्तास्ते कथं समुच्चीयन्तामिति भावः ॥

(उद्योतः) पदान्तरेणाव्यवधानरूपासत्तिः—**आनुपूर्व्यम् । विक्षिप्ताः**—विभिन्नदेशस्थाः ॥ भाष्ये-**यथेष्टं संबन्धः**—इष्टवाक्यार्थबोधजनकत्वरूपः ॥

(समाधानभाष्यम्)

अनानुपूर्व्येणापि सन्निविष्टानां यथेष्टमभिसंबन्धो भवति । तद्यथा—अनड्वाहमुदहारि या त्वं हरसि शिरसा कुम्भं, भगिनि साचीनमभिधावन्तमद्राक्षीरिति । तस्य यथेष्टमभिसंबन्धो भवति—उदहारि भगिनि या त्वं कुम्भं हरसि शिरसा, अनड्वाहं साचीनमभिधावन्तमद्राक्षीरिति ॥

(प्रदीपः) **अनानुपूर्व्येणापीति ।** लोपशब्द आवर्त्यते ॥ तत्र लोपाजादेश इति विज्ञायते । तत्र द्विर्वचनविधौ लोपाजादेशस्यासंभवात्सवर्णादिविधौ तु तस्यैव संभवान्न तत्रादेशस्य लोपो विशेषणम् । पदान्ते तु यद्यपि संभवव्यभिचारौ स्तः—तानि सन्ति, कानि यन्ति इति, तथापि **न पदान्तेति** योगविभागात् तद्विधौ लोपो न विशेषणमिति पारिशेष्यात् **स्वरदीर्घयलोपेषु लोपाजादेशो न स्थानिवदिति** विज्ञायते । स्मृति-

शास्त्रत्वाच्चास्य एतावन्तोऽर्थाः संनिहिता इत्येतावत्प्रतीयते । ग्रहणकवाक्यात्तु लक्ष्यसंस्कारकं प्रक्रियावाक्यं उपप्लवत इति सिद्धमिष्टम् ॥ **अनड्वाहमिति** । पाठक्रमादार्थक्रमो बलीयानिति यथेष्टमत्राभिसंबन्धः ॥

(उद्द्योतः) असंभवादिति । चख्नतुः-जग्मतुरित्यादौ संभवाच्चिन्त्यमिदम् ॥ **पारिशेष्यादिति** । श्नौस्थ्यानायेत्यपि बोध्यम् ॥ पूलावदिति । पूर्वोक्तो नियमोऽपीत्यर्थः ॥ ननु सत्रस्यैकत्वाच्चैवम्मात्रविषये तादृशो वाक्यार्थो दुर्वच इत्यत आह—ग्रहणकवाक्यात्विति ॥ पाठक्रमादिति । [अर्थक्रमो नाम राजपुरप्रवेशन्यायेन स्वस्वाकाङ्क्षितार्थान्वयक्रमः ।] एवं च कल्पितासद्भावाक्याद्बोधः, तत्र च तात्पर्यं नियामकमिति भावः ॥ भाष्यात्तु आसत्यभावेऽपि पदार्थोपस्थितौ आकाङ्क्षावशात्स्वस्यनुसारेणान्वयबोध इति लभ्यते ॥ साध्रीममित्यस्य तिर्यग्गच्छन्तमित्यर्थः ॥

(३५८ न्यूनताक्षेपवार्तिकम् ॥ २ ॥)

॥ * ॥ क्विलुगुपधात्वचङ्परनिर्ह्रासकुत्वेषूपसंख्यानम् ॥ * ॥

(भाष्यम्)

क्विलुगुपधात्वचङ्परनिर्ह्रासकुत्वेषूपसंख्यानं कर्तव्यम् ॥

(उद्द्योतः) क्विलुगिति । वार्तिके क्वावित्यत्र विधावित्येतदध्याह्रियते, तेन क्विनिमित्तविधावित्यर्थः । आवृत्त्या क्वावित्यादेशेनापि संबध्यते, क्विनिमित्तादेश इत्यर्थः । तदेतदर्थतः पठ्यते—क्वौ लुप्तमिति । इदं च काचित्कमिति वक्ष्यते ॥ एवं लुप्ते आदेशे, उपधात्वप्रयुक्ते कार्ये, चङ्परह्रस्वे, कुत्वे च स्थानिवत्त्वं नेत्यर्थः ॥

(क्विग्रहणोदाहरणम्)

(आक्षेपभाष्यम्)

क्वौ किमुदाहरणम् ?

(उद्द्योतः) भाष्ये— क्वावित्यस्य- क्वौ लुप्तमित्यर्थे उदाहरणम् ॥

(समाधानभाष्यम्)

कण्डूयतेरप्रत्ययः-कण्डूरिति ॥

(उद्द्योतः) कण्डूरिति यगन्तात् क्विप् । अत्र यण् न, यलोपश्च भवतीति भावः ॥

(समाधानबाधकभाष्यम्)

नैतदस्ति । यलोपविधिं प्रति न स्थानिवत् ॥

(उद्द्योतः) तैत्राग्न्यं खण्डयति—यलोपेति ॥

(समाधानान्तरभाष्यम्)

इदं तर्हि—पिपठिषतेरप्रत्ययः । पिपठीः ॥

(बाधकभाष्यम्)

नैतदस्ति । दीर्घविधिं प्रति न स्थानिवत् ॥

(उद्द्योतः) पिपठीरिति । अलोपस्य स्थानिवत्त्वेन रेफान्तस्यापदत्वाद्दीर्घो न स्यादिति भावः ॥ अत्र रुत्वमप्येतदधीनमेव ॥

(समाधानान्तरभाष्यम्)

इदं तर्हि—लावयतेः-लौः । पावयतेः-पौः ॥

(प्रदीपः) लौरिति । णिलोपस्य स्थानिवत्त्वादूठ् न स्यात् ॥

(उद्द्योतः) लावयतेरिति । ण्यन्तलुनातेरित्यर्थः ॥ ऊठ्नेति । क्वौ वान्तस्यानङ्गत्वादिति भावः ॥ ऊठि एत्येधत्यूठीति वृद्धिः ॥

(बाधकभाष्यम्)

नैतदस्ति । अकृत्वा वृद्ध्यावादेशौ णिलोपः । प्रत्ययलक्षणेन वृद्धिर्भविष्यति ॥

(प्रदीपः) **अकृत्वेति** । **यलोपाविय**ङ्**यण्गुणवृद्धिदीर्घेभ्यः पूर्वविप्रतिषिद्धम्**इति णिलोपस्ततो वृद्धिः । आवादेशो वर्णाश्रयत्वात् प्रत्ययलक्षणेन न भवति । यथा- गोहितमित्यवादेशः । एतच्चान्तरङ्गत्वमनाश्रित्योक्तम् । तत्र त्वाश्रितेऽन्तरङ्गबहिरङ्गयोर्विप्रतिषेधाभावः ॥

(उद्द्योतः) वर्णाश्रयत्वादिति । अतः परिस्मिन्निति स्थानिवत्त्वं तु न, पूर्वेरनादिष्टादचः पूर्वत्वाभावात् ॥ तत्र त्विति । कौरक इत्यादौ णिस्थानिकवृद्धिविषये स चरितार्थः । तथैव चातो लोप इति सूत्रे भाष्ये स व्याख्यात इति भावः ॥ परे तु यस्वतुकोरिति ज्ञापकादनित्यत्वेनान्तरङ्गत्वमनाश्रित्य क्वौ लुप्तमिति न कार्यम्, नित्यत्वाच्च पूर्वं णिलोपः । वृद्धिस्त्वकृते णिलोपे उपदेशेन, कृते तु अतिदेशेनेत्यनित्या इति पूर्वपक्षाशयमाहुः ॥

(समाधानान्तरभाष्यम्)

इदं तर्हि—लवमाचष्टे लवयति । लवयतेरप्रत्यये- लौः, पौः । स्थानिवद्भावात् णेरूठ् न प्राप्नोति ॥

क्वौ लुप्तं न स्थानिवदिति भवति ॥

(प्रदीपः) **लवमाचष्ट इति** । 'क्वौ विधिं प्रति न स्थानिवत्' इत्यस्यार्थस्य प्रदर्शनायेदमुक्तम् ॥ इदं तु क्वौ लुप्तस्योदाहरणं—देवयतेः-द्यूरिति ॥

(उद्द्योतः) देवयतेरिति । ण्यन्तदिवेरित्यर्थः ॥ नन्वत्रोठ् क्वौ विधिमित्येव सिद्धः । न चोकारस्य वृद्धिः स्यात्, णेः स्थानिवत्त्वादिति वाच्यम् । ऊठ आदिष्टादचः पूर्वत्वादिति नेदमसाधारणमुदाहरणमिति चेन्न । सखीयतेः-सख्युरिति व्यत्याद्यसूत्रभाष्योक्तं, गोमत्यतेः-गोमानिति उगिदचामिति सूत्रभाष्योक्तं, व्यन्तपदेः-पाद् पद इति येन विधिरिति सूत्रभाष्योक्तं, कण्डूः पिपठीरित्यादौ यणभावरुत्वयोः सिद्धिश्च तस्याःसाधारणमुदाहरणम् ॥ सौनिहारकेऽनादिष्टादचः पूर्वत्वे तु इदमप्युदाहरणमिति बोध्यम् ॥

(समाधानबाधकभाष्यम्)

एवमपि न सिध्यति ॥

कथम् ?

क्वौ णिलोपः, णावकारलोपः, तस्य स्थानिवद्भावादूठ् न प्राप्नोति ॥

(समाधानसाधकभाष्यम्)

नैष दोषः । नैवं विज्ञायते—क्वौ लुप्तं न स्थानिवदिति ॥

कथं तर्हि ?

कौ विधिं प्रति न स्थानिवदिति ॥

(उद्योतः) नैवं विज्ञायते क्वौलुकमिति । नैवमेव विज्ञायते, किं त्विदमपि काचित्कं लक्ष्यसिद्धये आश्रयणीयमिति भावः ॥

(इति किंग्रहणोदाहरणनिरूपणम्)

(अथ लुग्ग्रहणोदाहरणम्)

(आक्षेपभाष्यम्)

लुकि किमुदाहरणम् ?

(समाधानभाष्यम्)

बिम्बं, बदरम् ॥

(प्रदीपः) बिम्बमिति । बिम्बीबदरीशब्दाभ्यां ङीमन्ताभ्यामनुदात्तादेश्चेत्यण्, तस्य फले लुक्, लुक् तद्धितलुकीति ङीषो लुक् । तस्य स्थानिवत्त्वाद्यस्येति लोपः प्राप्नोतीति प्रतिषेध उच्यते । तद्धितस्य स्थानिनः परत्वात्तल्लुकोऽपि परत्वाश्रयणात् परनिमित्तकत्वं स्त्रीप्रत्ययलुक आश्रीयते । अन्यथा–अभावेन पौर्वापर्याभावात् कुतः परनिमित्तकत्वम् । अथवा बुद्धिपरिकल्पितमभावेनापि पौर्वापर्यं भवति ॥

(समाधानबाधकभाष्यम्)

नैतदस्ति । पुंवद्भावेनाप्येतत्सिद्धम् ॥

(प्रदीपः) पुंवद्भावेनेति । भस्याढे तद्धित इति पुंवद्भावः ॥ अत्र च भाषितपुंस्कत्वं नाश्रीयते इत्येतदुक्तम् । तदाश्रये तु नास्ति पुंवद्भावः ॥

(उद्योतः) तदाश्रये इति । 'वृक्षजातिः स्त्रियां' इति लिङ्गानुशासनाद् वृक्षे स्त्रीलिङ्गत्वं फले च नपुंसकत्वमिति भावः ॥ वस्तुत आम्र इत्यादौ लिङ्गानुशासनस्य व्यभिचारादेतद्भाष्यप्रामाण्याच्च बिम्बबदरामलका वृक्षेऽपि त्रिलिङ्गा इत्याहुः ॥

(समाधानान्तरभाष्यम्)

इदं तर्हि—आमलकम् ॥

(प्रदीपः) आमलकमिति । वृद्धत्वान्मयटो विधानाद्भुत्वाभावः ॥

(समाधानबाधकभाष्यम्)

एतदपि नास्ति । वक्ष्यत्येतत्—*फले लुग्वचनानर्थक्यं प्रकृत्यन्तरत्वात्* इति ॥

(प्रदीपः) प्रकृत्यन्तरत्वादिति । बिम्बबदरामलकादयो न यौगिकाः शब्दाः । किं तर्हि ? विशिष्टफलजातिवाचिन इत्यर्थः ॥

(उद्योतः) किंतर्हीति । यौगिकत्वे हि वृक्षसंबन्धात् फले, न पुनः फलसंबन्धाद्वृक्षे-इत्यत्र विनिगमनाऽसंभवादिति भावः ॥ विशिष्टेति । विजातीयेत्यर्थः ॥

(समाधानान्तरभाष्यम्)

इदं तर्हि—पञ्चभिः पट्वीभिः क्रीतः-पञ्चपटुः, दशपटुरिति ॥

(प्रदीपः) पञ्चभिरिति । आर्हादिति ठक्, तस्याध्यर्धपूर्वेति लुक् । लुक् तद्धितलुकीति ङीषो लुक् । अन्तरङ्गानपि विधीन् बहिरङ्गो लुग् बाधत इति यणादेशः पूर्वं न प्रवर्तते । कृते तु लुकि तस्य स्थानिवत्त्वाद्यणः प्रसङ्ग इति स्थानिवत्त्वनिषेध उच्यते । अव्यविकन्यायेन पटुशब्दान्तादेव ठग् भविष्यति न तु पट्वीशब्दान्तादिति चेत्, प्रतिपत्तिगौरवप्रसङ्गः ॥

(उद्योतः) अन्तरङ्गानपीति । अस्य न्यायस्यान्तरङ्गनिमित्तविनाशकलुक एव तदन्तरङ्गबाधकताबोधकत्वे तु तत्परिभाषाप्रवृत्त्यभावसंपादकस्थानिवत्त्वनिषेधायेदमिति बोध्यम् ॥ अव्यविकेति । वोतो गुणेति ङीषो वैकल्पिकत्वादिति भावः ॥ प्रतिपत्तिगौरवेति । ज्ञानगौरवेत्यर्थः ॥

(समाधानबाधकभाष्यम्)

ननु चैतदपि पुंवद्भावेनैव सिद्धम् ॥

कथं पुंवद्भावः ?

भस्याढे तद्धिते पुंवद्भवतीति ॥

(समाधानसाधकभाष्यम्)

भस्येत्युच्यते । यजादौ च भसंज्ञा भवति । न चात्र यजादिं पश्यामः ॥

(समाधानबाधकभाष्यम्)

प्रत्ययलक्षणेन यजादिः ॥

(समाधानसाधकभाष्यम्)

वर्णाश्रये नास्ति प्रत्ययलक्षणम् ॥

(प्रदीपः) वर्णाश्रय इति । यद्यपि पुंवद्भावे सिद्धश्च प्रत्ययविधावित्यस्ति तथापि यत्र भावि भत्वं तत्र पुंवद्भावः । इह तु लुकि भत्वाभावात्कुतः पुंवद्भावः ?

(उद्योतः) ननु भसंज्ञकस्य न पुंवत्त्वम्, येन वर्णाश्रयतया भत्वाभावेन पुंवत्त्वं न स्यात्, किंतु तत्प्रत्ययविषये पूर्वमेव पुंवत्त्वप्रतिपत्तिरत आह—यद्यपीति ॥ इह तु लुकीति । अनेन न लुमतेति निषेधान्न प्रत्ययलक्षणम् । किंच लभिन्नतद्धितविषयाभावादपि न तत्प्रवृत्तिरित्यपि ध्वनितम् । किंचान्तरङ्गानपीति न्यायेनैकादेशात्पूर्वमेव लुकि प्रत्ययलक्षणसत्त्वेऽपि यजादित्वाभावान्न भत्वम् । न च वर्णप्राधान्याभावात्कथं वर्णाश्रये नास्तीत्युक्तिर्भगवत इति वाच्यम् । प्रत्ययलक्षणसूत्रस्य नियमार्थत्वमिति पक्षेऽदोषात् ॥

(समाधानबाधकभाष्यम्)

एवं तर्हि—"ठक्छसोश्च" इत्येवं भविष्यति ॥

(समाधानसाधकभाष्यम्)

ठक्छसोश्चेत्युच्यते । न चात्र ठक्छसौ पश्यामः ॥

(बाधकभाष्यम्)

प्रत्ययलक्षणेन ॥

(समाधानसाधकभाष्यम्)

"न लुमता तस्मिन्" इति प्रत्ययलक्षणस्य प्रतिषेधः ॥

न खल्वप्यवश्यं ठगेव क्रीतप्रत्ययः, क्रीताद्यर्था एव वा तद्धिताः ॥

किं तर्हि ?

अन्येऽपि तद्धिता ये लुकं प्रयोजयन्ति । पञ्चेन्द्राण्यो देवता अस्येति-पञ्चेन्द्रः, पञ्चाग्निः, दशाग्निः ॥

(प्रदीपः) किं तर्ह्यन्येऽपीति । यत्र पुंवद्भावो नास्ति ॥ पञ्चेन्द्र इति । साऽस्य देवतेत्यण्, द्विगोर्लुगनपत्य इति लुक्, ततो ङीपो लुकि तस्य स्थानिवत्त्वात् ङीपा सन्नियुक्त आनुक् श्रूयेत, यथेन्द्राणीति । तथा पञ्चाग्नाय्यो देवता अस्य-पञ्चाग्निरिति ऐकारः श्रूयेत । समानायामाकृतौ भाषितपुंस्कत्वाभावाद्वर्णाश्रयत्वाद्वृत्त्वाभावाच्च पुंवद्भावो नास्ति । अथवा यस्येति लोपप्रसङ्गः । लुकि च स्थानिवत्त्वनिषेधात् 'आधीध्ये' इति परस्मिन्नित्यस्य पूर्वसूत्रे प्रत्युदाहरणमुपपद्यते । शब्लुकि कृते टेरेत्वस्य स्थानिवद्भावादव्यवधानाच्च लोपप्रसङ्गात् ॥

(उद्द्योतः) न लुमताङ्गस्येति यथाश्रुतेऽभ्युपेत्याऽपि ठक्छसोश्चेति पुंवत्त्वं-भाष्ये आह—न खल्वपीति ॥ नन्वानुक् न ङीपेत्युच्यते, येन स्थानिवत्त्वेन तदापद्येत आह—संनियुक्त इति । एवं च संनियोगशिष्टपरिभाषाप्राप्तानुग्निवृत्तिप्रतिबन्धद्वारा आनुग्रक्षणमेव पूर्वविधिरिति भावः ॥ अत एव 'ऐनेयः' इत्यादौ यस्येति लोपे नस्य श्रवणम् । अत एवाचः परस्मिन्निति सूत्रे विधिशब्दस्य भावसाधनत्वे पूर्वस्य विधानं प्रति-पूर्वस्य भावं प्रति पूर्वः स्यादिति स्थानिवदित्यर्थ उक्तः । पूर्वः स्यादित्यस्य 'पूर्वः स्थितः स्यात्' इत्यप्यर्थो बोध्यः । एवं च पूर्वसूत्रे तन्त्रेणोभयसाधनविधिशब्दघटितग्रहणम् ॥ यत्तु कैयटादिभिः संनियोगशिष्टपरिभाषाऽनित्यत्वेनेदं साधितम्, तद्वृथैव ॥ नन्वत्रापि भस्याढे इति पुंवत्त्वं स्यादत आह—समानायामिति । पुंसि इन्द्रत्वादि प्रवृत्तिनिमित्तं, स्त्रियां तु तत्संबन्ध इति भावः ॥ नन्वेवमग्नायी देवता अस्य-आग्नेयं हविरिति उदाहरणासिद्धिः, तस्मादारोपितेन्द्रत्वाद्येव स्त्रियामपि प्रवृत्तिनिमित्तमित्यत आह—वर्णाश्रयत्वादिति । अणो लुकि न लुमतेति निषेधात् तन्निमित्तकतद्धितविषयाभावाच्चेत्यपि बोध्यम् ॥ अथ वेति । ङीलुकः स्थानिवत्त्वेन भत्वादीकारपरत्वाच्चेति भावः ॥ शब्लुकीति । अन्यथा शब्लुकः स्थानिवत्त्वेन व्यवधानात्प्राप्तिरेव नेति भावः ॥ वस्तुतः शब्लुकः परनिमित्तकत्वाभावादेव न स्थानिवत्त्वप्रसक्तिः । अत एव 'जुहुतः' इत्यादौ श्लोः स्थानिवत्त्वाच्च गुणः ॥

(इति लुग्ग्रहणोदाहरणम्)

(अथोपधात्वोदाहरणनिरूपणम्)

(आक्षेपभाष्यम्)

उपधात्वे किमुदाहरणम् ?

(समाधानभाष्यम्)

पिपठिषतेरप्रत्ययः पिपठीरिति ॥

(समाधानबाधकभाष्यम्)

नैतदस्ति । दीर्घविधिं प्रति न स्थानिवत् ॥

(समाधानान्तरभाष्यम्)

इदं तर्हि—सौरी बलाका ॥

(समाधानबाधकभाष्यम्)

नैतदस्ति । यलोपविधिं प्रति न स्थानिवत् ॥

(समाधानान्तरभाष्यम्)

इदं तर्हि—पारिखीयः ॥

(प्रदीपः) पारिखीय इति । परिखाशब्दाच्चातुरर्थिकेऽणि कृते आकारलोपस्य स्थानिवत्त्वात् पारिखे भव इति वृद्धादकेकान्तखोपधादिति छो न स्यात् ॥

(इत्युपधात्वोदाहरणनिरूपणम्)

(अथ चङ्परनिर्ह्रासोदाहरणनिरूपणे भाष्यवार्तिकम्)

॥ चङ्परनिर्ह्रासे चोपसंख्यानं कर्तव्यम् ॥

(भाष्यम्)

वादितवन्तं प्रयोजितवान्-अवीवदद्वीणां परिवादकेन ॥

किं पुनः कारणं न सिध्यति ?

योऽसौ णौ णिर्लुप्यते तस्य स्थानिवद्भावाद्ध्रस्वत्वं न प्राप्नोति ॥

(उद्द्योतः) भाष्ये—योऽसौ णाविति । णेर्णिच्युपसंख्यानमिति सिद्धमेतत् ॥ वक्तृभेदान्न दोष इति तत्त्वम् ॥ अत एव ज्ञापकात् प्रायोगिकमच्स्थानिकादेशत्वमेवाचः परस्मिन्नित्यत्रपूर्वस्युपयोगीति बोध्यम् ॥

(बाधकभाष्यम्)

ननु चैतदप्युपधात्वविधिं प्रति न स्थानिवदित्येव सिद्धम् ॥

(साधकभाष्यम्)

विशेषित एतद्वक्तव्यम् ।

क ?

प्रत्ययविधाविति । इह मा भूत्—पटयति, लघयति ॥

(उद्द्योतः) प्रत्ययविधाविति । अत एव चङ्परह्रस्वे निषेधः सार्थकः ॥ ननूपधात्वे स्थानिवत्त्वनिषेधेऽपि अणित्परत्वांशे णिपरत्वांशे च तस्य दुर्वारत्वेन न पटयतीत्यादौ वृद्धिर्नापि ह्रस्वनिषेधो व्यर्थ इति चेत्, न । प्रत्ययस्याङ्गांशे उपस्थिताकाङ्क्षत्वेन ञ्णितीत्यादेरङ्गविशेषणत्वस्यैवौचित्यात् । उपधात्वप्रयुक्तकार्ये एव मन्निषेधेन णित्परत्वाद्यंशेऽपि स्थानिवत्त्वनिषेधाच्च ॥

(इति चङ्परनिर्ह्रासोदाहरणम्)

(अथ कुत्वोदाहरणनिरूपणम्)

कुत्वे चोपसंख्यानं कर्तव्यम् । अर्चयतेरर्कः, मर्चयतेर्मर्कः ॥

(उद्द्योतः) अर्क इति । कर्मणि घञ् । चजोरिति कुत्वमिति भावः ॥

(उपसंख्यानबाधकभाष्यम्)

नैतद् घञन्तम् । औणादिक एष कशब्दः, तस्मि-

आष्टमिकं कुत्वम् ॥

(उद्योतः) नैतद् वजन्तमिति । पूरंघः प्रत्ययादिरर्थः ॥

(उपसंख्यानसाधकभाष्यम्)

एतदपि णिचा व्यवहितत्वान्न प्राप्नोति ॥

(उद्योतः) एतदपीति । एवं च 'कुत्वे' इत्यावश्यकमिति भावः ॥

(३५९ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ पूर्वत्रासिद्धे च ॥ * ॥

(भाष्यम्)

पूर्वत्रासिद्धे च न स्थानिवदिति वक्तव्यम् ॥

(उद्योतः) वस्तुतस्तदनावश्यकमित्याह-पूर्वत्रासिद्धे इति । अर्थः परंत्रिपादीस्थेतद्दृष्ट्या त्रिपाद्या असिद्धत्वेन न्यायसिद्धानुवादोऽयम् । तत्फलं स्वविदेशान्तराणां वतिघटितानामन्यावधिवदित्यादीनां त्रिपाद्यां प्रवृत्तिबोधनम् । तेन 'अमी' 'क्षीरपेण' इत्यादौ तत्सिद्धिरिति दिक् ॥

(भाष्यम्)

किं प्रयोजनम् ?

(३६० प्रयोजनवार्तिकम् ॥ २ ॥)

॥ * ॥ प्रयोजनं क्सलोपः सलोपे ॥ * ॥

(भाष्यम्)

क्सलोपः सलोपे प्रयोजनम् । अधुग्ध, अधुग्धाः । "लुग्वा दुहदिहलिहगुहामात्मनेपदे दन्त्ये" इति लुग्ग्रहणं न कर्तव्यं भवति ॥

(प्रदीपः) क्सलोप इति । अधुग्धमर्थं लुग्वचनं कर्तव्यमेव । तदर्थं-लुग्ग्रहणं नेति छेदं कुर्वन्ति । कर्तव्यं भवतीत्युत्तरम् । अवश्यकार्यमित्यर्थः ॥

(उद्योतः) अधुग्धेति । क्सस्यान्त्यलोपे झलो झलीति सलोपे तदीयाल्लोपस्य स्थानिवत्त्वं न ॥

(प्रयोजने भाष्यवार्तिकम्)

॥ दध आकारलोप आदिचतुर्थत्वे प्रयोजनम् ॥

(भाष्यम्)

धत्से - धद्ध्वे - धद्ध्वमिति । "दधस्तथोश्च" इति चकारो न कर्तव्यो भवति ॥

(प्रदीपः) चकारो न कर्तव्य इति । झषन्तत्वात् पूर्वेणैव सिद्धत्वात् ॥

(उद्योतः) (भाष्ये) चतुर्थत्वे इति । भष्भावे - इत्यर्थः ॥ चकार इति । स्ध्वोरित्यनुकर्षणार्थं इत्यर्थः ॥ पूर्वेणैवेति । एकाचो बश इत्यनेनेत्यर्थः ॥

(प्रयोजने भाष्यवार्तिकम्)

॥ हलो यमां यमि लोपे प्रयोजनम् ॥

(भाष्यम्)

आदित्यः । "हलो यमां यमि लोपः" सिद्धो भवति ॥

(प्रयोजने भाष्यवार्तिकम्)

॥ अल्लोपणिलोपौ संयोगान्तलोपप्रभृतिषु प्रयोजनम् ॥

(भाष्यम्)

पापच्यतेः—पापक्तिः । यायज्यतेः—यायष्टिः । पाचयतेः—पाक्तिः । याजयतेः—याष्टिः ॥

(प्रदीपः) पापक्तिरिति । क्तिच् । संयोगान्तलोपादयः पदान्तविधौ स्थानिवत्त्वनिषेधादसिद्धा इति भाष्ये नोदाहृताः । स्कन्दयतेः स्कन्, काष्ठं तक्षयतीति काष्ठतक् । संयोगादिलोपलत्वणत्वेष्विति वचनात्संयोगादिलोपे स्थानिवत्त्वात्तदभावादत्र संयोगान्तलोपः । दोहयतेः—धोक् । लेहयतेः-लेट् । उणादीनामव्युत्पन्नत्वात् कियोः-गियोः-इत्यत्र दीर्घाभावः ॥

(उद्योतः) ननु 'संयोगान्तलोपप्रभृतिषु' इत्युक्त्वा तं विहाय कुत्वाद्युदाहरणदाने बीजाभावोऽत आह—संयोगान्तेति ॥ पदान्तेति । चिन्त्यमेतत् । पदचरमावयव एव तन्निषेधात् परपदस्यादेशस्यैव तेन स्थानिवत्त्वनिषेधाच्चेति ॥ तदुदाहरणानि दर्शयति—स्कन्दयतेरित्यादिना ॥ काष्ठतगिति । न च काष्ठशगेव नास्ति, कुतः काष्ठशक्स्यातेति परेश्चेति सूत्रस्थभाष्याद् एषामनभिधानमिति वाच्यम् । यत्र संयोगादिलोपप्रसक्तिस्तद्विषयत्वेनानभिधानस्यादोषात् ॥ नन्वत्र संयोगादिलोपः प्राप्नोति । न च तत्र पदान्तविधित्वमिति न तेन सिद्धिरत आह—संयोगादिलोपेति ॥ केचित्तु एतद्भाष्यप्रामाण्यादेषां प्रयोगाणामनभिधानमेवेत्याहुः ॥

(३६१ प्रयोजनवार्तिकम् ॥ ३ ॥)

॥ * ॥ द्विर्वचनादीनि च ॥ * ॥

(भाष्यम्)

द्विर्वचनादीनि च न पठितव्यानि भवन्ति । पूर्वत्रासिद्धेनैव सिद्धानि भवन्ति ॥

किमविशेषेण ?

नेत्याह ॥

(३६२ शेषवार्तिकम् ॥ ४ ॥)

॥ * ॥ वरेयलोपस्वरवर्जम् ॥ * ॥

(भाष्यम्)

वरेयलोपं स्वरं च वर्जयित्वा ॥

(उद्योतः) भाष्ये—वरेयलोपस्वरवर्जमिति । सवर्णानुस्वारदीर्घादयः साहचर्यात् त्रैपादिका एव गृह्यन्ते इति भावः ॥ नन्वेवं पठन्ताण्णिजन्तप्रकृतिकण्यन्ताद्वा चिणि 'अशंशामि' 'अशामि' इत्यादौ दीर्घो न स्यात्, णिलोपाल्लोपयोः स्थानिवत्त्वादिति चेत्; न । णेर्णिच्युपसङ्ख्यानात् 'अशामि' इत्यस्य सिद्धेः ॥ अशंशामीति तु यङ्लुगन्ताण्णिचि भविष्यति । न हि यङ्यङ्लुकोः स्वरे रूपे वा विशेषः । 'शाशितम्' इत्यादौ विहितविशेषणाश्रयणाच्च दीर्घ इति दिक् ॥

अन्ये तु तृतीयषष्ठाध्यायस्थभाष्यप्रामाण्यादत्र दीर्घमप्युपलक्षयन्ति । एतच्च तत्रैव निरूपयिष्यामः ॥

(३६३ प्रतिप्रसववार्तिकम् ॥ ५ ॥)

॥ * ॥ तस्य दोषः संयोगादिलोपलत्वणत्वेषु ॥ * ॥

(भाष्यम्)

तस्यैतस्य लक्षणस्य दोषः संयोगादिलोपलत्वणत्वेषु ॥

(उदाहरणभाष्यम्)

संयोगादिलोप—काक्यर्थम्, वास्यर्थम् । "स्कोः संयोगाद्योरन्ते च" इति लोपः प्राप्नोति ॥

(उद्द्योतः) भाष्ये-काक्यर्थमिति । न च स्कोरिति सूत्रे झल्ग्रहणापकर्षेण झलन्तसंयोगस्यैव ग्रहणात् प्रकृते न दोष इति वाच्यम् । झलो लोपः संयोगान्तलोपः - इत्याष्टमिकभाष्येण संयोगादिलोपे तदसंबन्धबोधनात् । त्रिपाद्यां बहिरङ्गासिद्धत्वाप्रवृत्तेश्चेति भाष्याभिप्रायः ॥

(उदाहरणभाष्यम्)

लत्व—निगार्यते, निगाल्यते । "अचि विभाषा" इति लत्वं न प्राप्नोति ॥

(उद्द्योतः) निगाल्यत इति । नन्वत्रान्तरङ्गत्वादेव लत्वं सिध्यतीति वाच्यम् । सपादसप्ताध्यायीस्थकार्येप्रवृत्तियोग्यतया तदप्रवृत्तेः । त्रिपाद्यां तत्परिभाषाऽप्रवृत्तेश्च । न च प्रत्ययलक्षणम्, अल्विधित्वात् । प्रत्ययलक्षणसूत्रस्य नियमार्थताया एव भाष्यसंमतत्वात् ॥

(उदाहरणभाष्यम्)

णत्व—माषवपनी-व्रीहिवपनी । 'प्रातिपदिकान्तस्य' इति णत्वं प्राप्नोति ॥ न पदान्तद्विर्वचन० ५८

(प्रदीपः) **माषवपनीति** । समासान्तस्य नकारस्य णत्वं विधीयमानमल्लोपस्य स्थानिवत्त्वनिषेधात् ङीबुत्पत्तेः प्राक् समासंविधानात् प्राप्नोति - इति ॥ ५८ ॥

(उद्द्योतः) ननु स्थानिवत्त्वनिषेधेऽपि माषशब्दस्य वपनीशब्देन समासे समासान्तो नकारो नेति णत्वं न स्यादत आह— ङीबुत्पत्तेरिति । गतिकारकोपपदानां कृद्भिरिति वचनादिति भावः । न च बहिरङ्गासिद्धत्वेनेदं सिद्धम् । त्रिपाद्यां तदप्रवृत्तेरिति दिक् ॥ ५८ ॥

(५४ अतिदेशसूत्रम् ॥ १ । १ । ८ आ. ४)

द्विर्वचनेऽचि ॥ १ । १ । ५९ ॥

(प्रदीपः) **द्विर्वचने०** ॥ ५९ ॥ **अचः परस्मिन्नित्यत्र** योऽनादिष्टादचः पूर्व इति स्थितम्, साचूकस्य द्विर्वचनमिति पूर्वविधित्वाभावादप्राप्ते स्थानिवत्त्वं विधीयते ॥ अथापि निमित्तात् पूर्वं इत्यस्मिन् पक्षे प्राप्तिः स्यात्, तथापि **न पदान्तद्विर्वचनेति** प्रतिषेधप्रसङ्गादिदं वचनम् ॥

(उद्द्योतः) द्विर्वचनेऽचि ॥ ५९ ॥ अथापीति । प्रौढिवादोऽयम्, तत्पक्षस्यास्थितत्वात् । नपदान्तसूत्रे आष्टमिकद्वित्वस्यैव ग्रहणाच्च ॥

(इष्टानुपपत्तिपरिहारः)

(३६४ आक्षेपसाधकवार्तिकम् ॥ १ ॥)

॥ * ॥ आदेशे स्थानिवदनुदेशात्तद्वतो द्विर्वचनम् ॥ * ॥

(भाष्यम्)

आदेशे स्थानिवदनुदेशात् तद्वतः ।

किंवतः ?

आदेशवतो द्विर्वचनं प्राप्नोति ॥

(प्रत्याक्षेपभाष्यम्)

तत्र को दोषः ?

(३६५ आक्षेपवार्तिकम् ॥ २ ॥)

॥ * ॥ तत्राभ्यासरूपम् ॥ * ॥

(भाष्यम्)

तत्राभ्यासरूपं न सिध्यति । चक्रतुः, चक्रुरिति ॥

(प्रदीपः) **आदेश इति** । कार्यातिदेश इति पूर्वः पक्षः ॥ चक्रतुरित्यत्र यणादेशे कृते एकाचो विधीयमानं द्विर्वचनमनच्कत्वादप्राप्तमिति स्थानिवत्त्वात् यणयुक्तस्यैव प्राप्नोति ॥

(उद्द्योतः) यण्युक्तस्यैवेति । यद्यपि स्थानिवत्त्वे द्विर्वचनं नित्यं तथापि यणपि नित्य इति परत्वात्स स्यादिति भावः । इदमेवाभिप्रेत्य भाष्ये-अभ्यासरूपं न सिध्यतीत्येतावदेवोक्तम्, न तु निन्यतुरित्यादावियङ उत्तरखण्डे श्रवणं स्यादित्यापादितम्; तस्यानित्यत्वेन ततः पूर्वं द्वित्वस्यैव प्रवृत्तेरिति ॥

(३६६ समाधानवार्तिकम् ॥ ३ ॥)

॥ * ॥ अज्ग्रहणं तु ज्ञापकं रूपस्थानिवद्भावस्य ॥ * ॥

(भाष्यम्)

यदयमज्ग्रहणं करोति तज् ज्ञापयत्याचार्यः— रूपं स्थानिवद्भवतीति ॥

कथं कृत्वा ज्ञापकम् ?

अज्ग्रहणस्यैतत्प्रयोजनम्—इह मा भूत्—जेघ्रीयते, देध्मीयते । यदि च रूपं स्थानिवद्भवति, ततोऽज्ग्रहणमर्थवद्भवति । अथ हि कार्यम्, नार्थोऽज्ग्रहणेन । भवत्येवाऽत्र द्विर्वचनम् ॥

(प्रदीपः) **अथ हीति** । कार्यातिदेशे हि घ्रीध्मीति भाव्यमेव द्विर्वचनेनेति किमज्ग्रहणेन ॥ नन्वन्यदज्ग्रहणस्य प्रयोजनं - भसेः क्सौ घसिभसोर्हलीत्युपधालोपे कृते द्विर्वचनं मा भूदिति । नैतदस्ति । सत्यसति वा द्विर्वचने 'प्सान्' इति श्रुतौ विशेषाभावात् । छान्दसश्चैवोपधालोपः, छन्दसि च दृष्टानु-

विधिः । रूपस्थानिवत्त्वे च निन्यतुरित्यत्र पूर्वमियङादेशे कृते स्थानिरूपातिदेशान् 'नी-नी' इति द्विर्वचने **एरनेकाच** इति यणा बाधितत्वात्पुनरियङ् न प्रवर्तते ॥

(**उद्योतः**) दुर्लक्ष्योऽपि विशेषः सूक्ष्मदृशं प्रति दुर्वारोऽत आह—**छान्दसश्चैवेति** । एवं च **दातिप्रियाणीति**वद्द्वित्वाभाव इति भावः । अत्रोपधालोपस्य छान्दसत्वं वदता कसोर्लौकिकत्वमभ्युपेतम् ॥ ननु सिद्धान्ते द्वित्वनिमित्तेऽचीत्यर्थः, तदाऽचीति किमर्थम् ? अरिरिषतीत्यादिसिद्धये कार्यमनुभवतः कार्यिणो निमित्तत्वानाश्रयणेनात्रापि **नटभार्याचद्दयअनानि** इति पाष्ठभाष्यरीत्या द्वितीयाजवधिकस्य 'घ्रीय्' इत्यस्यैव द्वित्वप्राप्त्या यङः कार्यित्वेन द्वित्वनिमित्तत्वाभावात् कथं तन्निमित्तादेशे स्थानिवत्त्वप्रसक्तिरिति चेन्न । द्वितीयहल्पर्यन्तस्यैव द्वित्वमिति मते तत्सत्त्वात् । अत एव प्रातिशाख्ये उक्तम्—**स्वरान्तरे व्यञ्जनान्युत्तरस्येति** ॥ अरिरिषतीत्यादौ 'रि' इत्यस्य द्वित्वेऽपि इकारस्य सनवयवतया सनो द्वित्वानुभवेन तन्निमित्तत्वाभावादिति दिक् ॥ पाष्ठभाष्यरीत्या तु 'अधिजगे' इति व्यावर्त्यं बोध्यम् ॥

(३६७ समाधानबाधकाक्षेपवार्तिकम् ॥ ४ ॥)

॥ * ॥ तत्र गाङः प्रतिषेधः ॥ * ॥

(भाष्यम्)

तत्र गाङः प्रतिषेधो वक्तव्यः । अधिजगे । इवर्णाभ्यासता प्राप्नोति ॥

(**प्रदीपः**) **अधिजग इति** । कृते एशादेशे गाङ्-इति प्रक्रियाश्रयेण चोद्यम् । ङकारस्यानुबन्धत्वादिकारस्य गाङ् भवत्यजादेशः ॥

(**उद्योतः**) ननु लिटि विधीयमानस्य गाङः कथमच्यादेशत्वमत आह—**कृते इति** ॥ **ङकारस्येति** । प्रकृतसूत्रे प्रयोगे निवर्त्यस्यैव स्थानित्वेन ग्रहणं 'अचः परस्मिन्–' इतिवदिति भावः ॥

(समाधानसाधकभाष्यम्)

न वक्तव्यः । "गाङ्लिटि" इति द्विलकारको निर्देशः । लिटि लकारादाविति ॥

(**उद्योतः**) **द्विलकारक इति**–भाष्ये । एवं चाचि नायमिति भावः ॥ एवं च 'इदमज्ग्रहणव्यावर्त्यं' इति स्पष्टमेवोक्तमिति बोध्यम् ॥ न च सिद्धान्ते **आर्धधातुके लिटीत्या**दीनां तत्र विषयसप्तमीत्वेनानैमित्तिकत्वान्न तत्र दोष इति **वाच्यम्** । विषयसप्तमीत्वेऽपि बुद्धिकृतनिमित्तत्वस्य दुर्वारत्वेन सनैमित्तिकत्वमस्त्येवेति भाष्याशयात् ॥

(३६८ आक्षेपान्तरवार्तिकम् ॥ ५ ॥)

॥ * ॥ कृत्येजन्तदिवादिनामधातुष्वभ्यासरूपम् ॥ * ॥

(भाष्यम्)

कृत्येजन्तदिवादिनामधातुष्वभ्यासरूपं न सिध्यति ॥

कृति—अचिकीर्तत्-कृति ॥

एजन्त-जग्ले, मम्ले-एजन्त ॥

दिवादि—दुद्यूषति, सुस्यूषति-दिवादि ॥

नामधातु—भवनमिच्छति भवनीयति, भवनीयतेः सन्-बिभवनीयिषति ॥

(**प्रदीपः**) **कृत्येजन्तेति** । 'अचि योऽजादेशः स द्विर्वचने कर्तव्ये स्थानिवत्' इति सूत्रार्थमाश्रित्यैतदुच्यते ॥ **जग्ल इति** । शित्सदृशे आत्वमित्यत्र पक्षेऽयं दोषः ॥

(**उद्योतः**) अत्र पञ्च पक्षाः—अचि योऽजादेशः स द्वित्वे कार्ये स्थानिवदित्येकः, अजादौ प्रत्यये योऽजादेशः स द्वित्वे स्थानिवदिति **द्वितीयः**, द्विर्वचनशब्दस्याधिकरणल्युडन्तत्वादर्शआद्यजन्तत्वाद्वा द्वित्वनिमित्तेऽचीत्यादीति **तृतीयः**, द्वित्वनिमित्तेऽचि आदेशनिषेध इति **चतुर्थः**, द्वित्वनिमित्तेऽचि योऽजादेशः स स्थानिवद्-न भवति वा द्वित्वे कार्ये इति **पञ्चमः** ॥ तत्राद्ये दोषोद्भावनमित्याह—**अचीति** । कृतेरुपधायाश्चेतीत्त्वम् । तस्य च णिनिमित्ततयाऽच्यादेशता, अङ्गाक्षिप्ते प्रत्यये तद्विधानात् ॥ ननु आत्वं कथमच्यादेशः, अनैमित्तिकत्वादत आह—**शित्सदृश इति** । शिदिति तत्पुरुषः । इत्संज्ञकशकारादिप्रत्ययभिन्नप्रत्यय इत्यर्थः ॥ अन्तरङ्गत्वात्तिबादिषु एशि च कृते आत्वमिति भावः ॥ दिवेः सनि **सनीवन्तेती**डभावपक्षे **हलन्ताच्चेति** कित्वे **च्छ्वोरित्यू**ठि यणि **सन्यङोरिति** द्वित्वे रूपम् ॥

(पक्षान्तरेण समाधानभाष्यम्)

एवं तर्हि प्रत्यय इति वक्ष्यामि ॥

(३६९ द्वितीयपक्षदूषणवार्तिकम् ॥ ६ ॥)

॥ * ॥ प्रत्यय इति चेत् कृत्येजन्तनामधातुष्वभ्यासरूपम् ॥ * ॥

(भाष्यम्)

प्रत्यय इति चेत् कृत्येजन्तनामधातुष्वभ्यासरूपं न सिध्यति । दिवादय एके परिहृताः ॥

(**उद्योतः**) द्वितीयं निराकरोति—भाष्ये—**प्रत्यय इति चेदिति** ॥

(तृतीयपक्षाङ्गीकारे समाधानभाष्यम्)

एवं तर्हि—द्विर्वचननिमित्ते अचि अजादेशः स्थानिवत् इति वक्ष्यामि ॥

(**प्रदीपः**) **द्विर्वचननिमित्त इति** । अस्मिन् पक्षे 'जग्ले' इत्यपरिहृतम् । उत्तरत्र परिहरिष्यते ॥

(तृतीयपक्षे दूषणभाष्यम्)

स तर्हि निमित्तशब्द उपादेयः । न ह्यन्तरेण निमित्तशब्दं निमित्तार्थो गम्यते ॥

(समाधानभाष्यम्)

अन्तरेणापि निमित्तशब्दं निमित्तार्थो गम्यते । तद्यथा—"दधित्रपुसं प्रत्यक्षो ज्वरः" ज्वरनिमित्तमिति गम्यते ॥ "नड्वलोदकं पादरोगः" पादरोगनिमित्तमिति गम्यते ॥ "आयुर्घृतम्" आयुषो निमित्तमिति गम्यते ॥

(प्रदीपः) दधित्रपुसमिति । समाहारद्वन्द्वः, कर्मधारयो वा । दध्येव विशिष्टावस्थायुक्तं त्रपुसमुच्यते । तत्र द्विर्वचननिमित्तत्वात्तद्रूपारोपेणाजेव द्विर्वचनमुच्यते । अथवा अधिकरणे ल्युट् । द्विरुच्यते तस्मिन्निति द्विर्वचनम् ॥

(उद्योतः) त्रपुसमिति । तृपसमितिपाठान्तरम्, तृपुसमिति च ॥ कर्मधारयमुपपादयति—दध्येवेति ॥ विशिष्टावस्थेति । रूपरसगन्धान्तरयुक्तमित्यर्थः । आद्ये त्रपुसं—फलविशेषः । द्वितीये समासाभावेऽपि न क्षतिरिति बोध्यम् ॥ तद्रूपारोपेणेति । दृष्टान्तबलेन तथैव लाभात् ॥

(समाधानान्तरभाष्यम्)

अथवा-अकारो मत्वर्थीयः । द्विर्वचनमस्मिन्नस्ति सोऽयं द्विर्वचनः, द्विर्वचने-इति ॥

(प्रदीपः) एतदप्रतिपद्यमानं प्रति परिहारान्तरमाह—अथवा अकार इति ।

(उद्योतः) ननु दृष्टान्ते लक्षणायामव्यभिचारेण कार्यजननप्रतीतिः प्रयोजनम्, प्रकृते न किंचित्तथा-इति लक्षणा दुरुपपादेत्यत आह—अथवेति ॥

(आक्षेपभाष्यम्)

एवमपि न ज्ञायते—कियन्तमसौ कालं स्थानिवद्भवतीति ॥

(प्रदीपः) एवमपीति । एकत्वाद्द्विर्वचनशब्दस्य, तस्य चाङ्विशेषणे उपयुक्तत्वात् कालावधारणाभावः ॥

(उद्योतः) कालेति । द्विर्वचनविधानसमय एवेत्यवधारणाभाव इत्यर्थः । एवं च चक्रतुरित्याद्यसिद्धिः, पुनर्यणादेशानापत्तेरिति भावः ॥

(समाधानभाष्यम्)

यः पुनराह 'द्विर्वचने कर्तव्ये' इति, कृते तस्य द्विर्वचने स्थानिवन्न भविष्यति ॥

(आदेशनिषेधरूपचतुर्थपक्षाभ्युपगमभाष्यम्)

एवं तर्हि—प्रतिषेधः प्रकृतः सोऽनुवर्तिष्यते ॥

क्व प्रकृतः ?

"न पदान्तद्विर्वचन-" इति ॥ द्विर्वचननिमित्ते अचि अजादेशो न भवतीति ॥

(प्रदीपः) एवं तर्हीति । स्थानिवदिति नानुवर्तते इति भावः ॥

(आक्षेपभाष्यम्)

एवमपि न ज्ञायते—कियन्तमसौ कालमादेशो न भवतीति ॥

(समाधानभाष्यम्)

यः पुनराह—द्विर्वचने कर्तव्य इति, कृते तस्य द्विर्वचने अजादेशो भविष्यति ॥

(पञ्चमपक्षाभ्युपगमभाष्यम्)

एवं तर्हि—उभयमनेन क्रियते—प्रत्ययश्च विशेष्यते, द्विर्वचनं च ॥

(प्रदीपः) प्रत्ययश्चेति । द्विर्वचनेन प्रत्ययस्याक्षिप्तत्वात्तद्विशेषणं द्विर्वचनम् । अचीत्येतच्च । तस्य तदादिविधिर्भवति—अजादाविति ॥

(उद्योतः) प्रत्ययश्च विशेष्यते, द्विर्वचनं च इत्यस्य 'विवक्षितत्वेन निर्दिश्यते' इति शेषः ॥ तत्राश्रुतस्य प्रत्ययस्य कथं विशेष्यत्वमत आह—द्विर्वचनेनेति । अचीत्युपादानात्प्राप्तमिह द्विर्वचनं । तच्च प्रत्यये-इति । तेन तद्वाचकप्रत्ययपदाक्षेप इत्यर्थः ॥ तद्भावभावितामात्रेण निमित्ततया आश्रयणात्सन्यङन्तस्य द्वित्वेऽपि तदाक्षेपः । स च 'अचि' इत्यस्य श्रवणात्सप्तम्यन्तस्यैवेति भावः ॥ अचीत्येतच्च तस्येति । विशेषणमित्याकृष्यते ॥ तदादिविधिरित्यस्य तेनेत्यादिः ॥ तदयमर्थः—द्वित्वनिमित्ताजादिप्रत्ययनिमित्तोऽजादेशः स्थानिवद् द्वित्वे कर्तव्ये इति ॥

(आक्षेपभाष्यम्)

कथं पुनरेकेन यत्नेनोभयं लभ्यम् ?

(प्रदीपः) कथं पुनरिति । विरुद्धत्वादनयोरर्थयोरेकेन 'द्विर्वचने' इत्यनेन पदेनानुपादानादिति भावः ॥

(उद्योतः) विरुद्धत्वादिति । एवं च सहविवक्षाभावान्नैकशेषो वक्तुं शक्य इति भावः ॥

(समाधानभाष्यम्)

लभ्यमित्याह ॥

कथम् ?

एकशेषनिर्देशात् ॥ एकशेषनिर्देशोऽयम्—द्विर्वचनं च द्विर्वचनश्च-द्विर्वचनम् । द्विर्वचने कर्तव्ये, द्विर्वचनेऽचि प्रत्यय इति ॥

(प्रदीपः) एकशेषनिर्देश इति । सहविवक्षाभावेऽपि सरूपाणामित्येकशेषः संज्ञापरिभाषावल्लक्षणाङ्गत्वात्तस्येति प्रागेवोक्तम् । विभक्त्यन्तयोश्चैकशेषविधानादप्रातिपदिकत्वाच्च द्विवचनाभावः । अथवा-एकशेषेण समानफलत्वात्तन्त्रमावृत्तिर्वा लक्ष्यते ॥

(उद्योतः) प्रागेव— सर्वादीनीत्यत्र ॥ नन्वेकशेषे द्विवचनापत्तिरत आह—विभक्त्यन्तयोरिति । परिभाषावच्छास्त्रमात्रोपयोगित्वादिति भावः ॥ प्रातिपदिकानामेवैकशेषेऽप्याह—अथवेति । नीलोत्पलस्पर्धिनी नेत्रे तनुर्वेतिवदिति भावः । क्रमेण बोधाद्भावृत्तिर्बोद्धारं प्रति, उच्चारयितुस्तन्त्रम् । इह निमित्तशब्देन साक्षात्परम्परासाधारणं प्रयोजकम्, न तु साक्षादेवेत्याग्रहः, तद्भावभावितामात्रेण निमित्तत्वस्येष्टार्थाकारात् । अत एव 'चक्रतुः' इत्युदाहरणसङ्गतिः (३७० पञ्चमदूषणवार्तिकम् ॥ ७ ॥)

॥ * ॥ द्विर्वचननिमित्तेऽचि स्थानिवदिति चेण्णौ स्थानिवद्वचनम् ॥ * ॥

(भाष्यम्)

द्विर्वचननिमित्तेऽचि स्थानिवदिति चेण्णौ स्थानि-

वद्भावो वक्तव्यः । अवनुनावयिषति, अवचुक्षावयिषति ॥

(समाधानभाष्यम्)

न वक्तव्यः ॥

(२७१ समाधानसाधकवार्तिकम् ॥ ८ ॥)

॥ * ॥ ओः पुयण्जिषु वचनं ज्ञापकं णौ स्थानिवद्भावस्य ॥ * ॥

(भाष्यम्)

यदयम्—"ओः पुयण्ज्यपरे" इत्याह, तत् ज्ञापयत्याचार्यः—भवति णौ स्थानिवत् - इति ॥

(प्रदीपः) ओः पुयण्जिष्विति । न हि णौ कृतस्य स्थानिवद्भावमन्तरेण पुयण्जिषु सर्वेष्ववर्णपरेषु उवर्णान्तोऽभ्यासः संभवति । यियविषति - पिपविषते - इत्यत्रैवानेन स्थानिवद्भावात् । पु इति वर्गग्रहणात् - यणिति प्रत्याहारग्रहणात् - जग्रहणाच्च ज्ञापकाण्णौ कृतस्य स्थानिवद्भावोऽनुमीयते ॥ ननु तत्र णाविति नास्ति तत्कथं तत्रैव स्थानिवत्त्वानुमानं न तु निनवनीयिषति दिदवनीयिषतीत्यादावपि ॥ नैतदस्ति । येन नाव्यवधानमित्येकेनैव प्रत्ययेन तत्र व्यवधानाश्रयणाण्णेरेव केवलस्य व्यवधायकस्य संभवात् ॥

(उद्योतः) स्वोक्तसर्वेष्विसस्य - पुयण्जिष्विति भाष्ये निर्धारणसप्तमीनिर्देशस्य च फलमाह—पिपविषत इति ॥ सनेन - द्विर्वचनेऽचीत्यनेन ॥ न चाभोत्तरखण्डे जातयोरचोरचः परस्मिन्निति स्थानिवत्त्वेनावर्णपरत्वाभावात्कथमोः पुयणित्यस्य प्राप्तिरिति वाच्यम् । एतत्सूत्रारम्भसामर्थ्येनैव तदप्रवृत्तेः । सनीवन्तेति क्षिपूङिति चोभयत्रेद् ॥ नन्ववर्णपरपुयण्जयो णौ - प्रत्ययान्तरे च संभवन्ति तत्कथं 'णौ' इत्युक्तमित्याशङ्क्ते—नन्विति ॥ येन नेति । प्रकृतसूत्रे परस्मिन्निति वर्तते, तेन द्वित्वनिमित्तेऽजादौ प्रत्यये प्रत्ययान्तरेणाव्यवहिते परे सति योऽजादेशः स स्थानिवदिति सूत्रार्थः ॥ तथानेन ज्ञापनेन व्यवाये प्रवृत्तिर्ज्ञाप्यते । तत्र प्रत्ययव्यवधानं विना वर्गादीनामुदाहरणासंभवेन येन नाव्यवधानन्यायेनैकव्यवधाने एव प्रवृत्तिः । स च णिरेव संभवतीति भावः ॥ न चोह - ऋजु - अम्बुशब्दादिभ्य आचारक्विपि सनि इटि द्वित्वे गुणाद्यभावे उरविपतीत्यादावित्यार्थं वर्गादिग्रहणं चरितार्थम् । किंच भ्वादिभ्यो विजन्तेभ्य आचारक्विपि सनि बिभविपतीत्यादौ चरितार्थमिति कथं ज्ञापकत्वमिति वाच्यम् ॥ सनिग्रहेत्यत्रोपदेशाधिकाराभावस्य एकाच उपदेश इति सूत्रे भाष्ये ध्वनितत्वेनोक्तप्रयोगेषु तेन निषेधेनेटो दुर्लभत्वादेषामनभिधानाच्च । विचोऽसार्वत्रिकत्वाच्च ॥ एतेन दवादिभ्य आचारक्विपि सनि दिदविषतीत्यादावेकव्यवधानस्यैव सत्त्वेन दोष इत्यपास्तम् ॥ भाष्ये—णौ स्थानिवदिति । अत्र णाविति प्रत्ययग्रहणेन यस्माद्विहितस्तदादेरित्यस्योपस्थित्या तस्याचो णिनिमित्तकादेश इत्यर्थः ॥ यदि त्वनियमप्रसक्त्यभावेन नियमफलाभावात्तस्या नोपस्थितिः, अत एव ह्रस्वस्य पिपीत्यादौ न तदुपस्थितिरित्युच्यते । तर्हि मास्तु । णौ पर इत्यर्थे रेफेण व्यवधानात्पुस्फारयिषतीत्याद्यसिद्धिरिति बोध्यम् ॥ ज्ञापनफलं तुतावयिषतीत्यादि ॥

(आक्षेपभाष्यम्)

यद्येतत् ज्ञाप्यते 'अचिकीर्तत्' अत्रापि प्राप्नोति ॥

(समाधानभाष्यम्)

तुल्यजातीयस्य ज्ञापकम् ॥

(उद्योतः) तुल्यजातीयस्येति । प्वादिघटितधात्वच्तुल्यस्याच आदेश इत्यर्थः । [षष्ठ्यन्तस्य षष्ठ्यन्ताच इत्यनेनैवान्वययोग्यत्वादिति बोध्यम् ॥]

(आक्षेपभाष्यम्)

कश्च तुल्यजातीयः ?

(उद्योतः) अच्त्वेन तुल्यत्वं कतोऽपीति पृच्छति – कश्चेति ॥

(समाधानभाष्यम्)

यथाजातीयकाः पुयण्जयः ॥

(उद्योतः) उत्तरयति—यथाजातीयका इति । प्वादिघटितधात्वच इत्यर्थः । प्वादिभिरचस्तुल्यत्वासंभवात् ॥

(आक्षेपभाष्यम्)

कथंजातीयकाश्चैते ?

(समाधानभाष्यम्)

अवर्णपराः ॥

(उद्योतः) अवर्णपरा इति । अवर्णपरत्वसंपादकादेशस्थानिन इत्यर्थः ॥ एवं चावर्णपरत्वसंपादकादेशस्थानित्वेन तुल्यतेति भावः ॥ एवं च 'औनमत्' 'औजढत्' इत्यादि चिन्त्यमेव ॥ किंच यत्र द्विरुक्तौ परभागस्थायोऽजवर्णस्तत्रेदमिति द्विर्वचनेऽचीत्यादौ भाष्यकैयटयोः स्थितमिति माधवोक्तं कथं भाष्यारूढमित्यपि चिन्त्यमेवेत्याहुः ॥

(आक्षेपभाष्यम्)

कथं जग्ले - मम्ले ? ॥

(समाधानभाष्यम्)

अनैमित्तिकमात्वम्, शिति तु प्रतिषेधः ॥

(उद्योतः) अनैमित्तिकमात्वमिति । अत एव ह्वावामश्चेति हेतौ कथमार्थं पुनरण्विधानं चरितार्थमिति पर्युदासपक्षेऽप्यदोषमादेच इत्यत्र भाष्यकारो वक्ष्यति ॥

(सूत्रप्रयोजननिरूपणम्)

(आक्षेपभाष्यम्)

कानि पुनरस्य योगस्य प्रयोजनानि ?

(प्रदीपः) कानि पुनरिति । अन्यथासिद्धत्वात्प्रश्नः ॥

(समाधानभाष्यम्)

पपतुः, पपुः । तस्थतुः, तस्थुः । जग्मतुः, जग्मुः । आटिटत्, आशिशत् । चक्रतुः, चक्रुरिति । आल्लोपोपधालोपणिलोपयणादेशेषु कृतेष्वनच्कत्वात् द्विर्वचनं न प्राप्नोति ॥ स्थानिवद्भावाद्भवति ॥

(उद्योतः) अनच्कत्वादिति । आटिटदित्यत्र णिलोपे धातोर्द्वितीयस्याप्रहितत्वादित्यर्थो बोध्यः ॥

(समाधानबाधकभाष्यम्)

नैतानि सन्ति प्रयोजनानि । पूर्वविप्रतिषेधेनाप्ये-

तानि सिद्धानि ॥

कथम् ?

वक्ष्यति ह्याचार्यः—*द्विर्वचनं यणयवायावादेशाल्लोपोपधालोपणिलोपकिकिनोरुत्वेभ्यः* इति ॥

(प्रदीपः) **पूर्वविप्रतिषेधेनापीति ।** अपूर्वो वाचनिकः पूर्वविप्रतिषेधः । न हि नित्यानामनित्येन द्विर्वचनेन न्याय्यो विप्रतिषेधः ॥ अथ निन्यतुरिति कथं नह्यत्रेयङ् परिगणितः ॥ एवं तर्हि **प्रकल्प्य चापवादविषयमिति** न्यायात् यणाऽत्र भवितव्यमितीयङ् न प्रवर्तत इति द्विर्वचने कृते **एरनेकाच** इति यण् सिद्धम् ॥

(उद्द्योतः) पूर्वविप्रतिषेधेनाप्येतानीति । द्विर्वचनेऽचीति स्वसाध्यानि, णौ **स्थानिवदिति** शास्त्रसाध्यानि चेत्यर्थः ॥ **न हि नित्यानामिति ।** आल्लोपादीनामित्यर्थः ॥ **द्विर्वचनेऽची**त्यादेरभावे द्विर्वचनमनित्यम् ॥ भाष्ये—वक्ष्यति हीति । दाधान्साल्लानिति सूत्रे ॥ **यणाऽत्र भाव्यमिति ।** यदीयङ् स्यात् तर्हि स स्यादिति तत्सम्भावनासत्त्वादित्यर्थः ॥ अग्लावित्याद्यर्थं वृद्धिपाठोऽप्यत्र बोध्यः ॥ वस्तुतोऽत्र यणादिग्रहणं अचूस्थानिकस्य द्विर्वचनात्परस्य विधेरुपलक्षणं बोध्यम् ॥

(समाधानसाधकभाष्यम्)

स पूर्वविप्रतिषेधो न पठितव्यो भवति ॥

(उद्द्योतः) सूत्रारम्भवादी आह—सपूर्वविप्रतिषेध इति ॥

(आक्षेपभाष्यम्)

किं पुनरत्र ज्यायः ?

(उद्द्योतः) उभयोः समतया तृतीयः पृच्छति—किं पुनरिति ॥

(समाधानभाष्यम्)

स्थानिवद्भाव एव ज्यायान् । पूर्वविप्रतिषेधे हि सतीदं वक्तव्यं स्यात्—*औदोदादेशस्य उद्भवति चुड्डुतुशरादेरभ्यासस्य* इति ॥

(प्रदीपः) **औदोदादेशस्येति ।** औदोतोरादेशो यस्मिन्नङ्गे तस्य योऽभ्यासः—चुड्डुतुशरादिः, तस्य योऽकारस्तस्योकारादेशो भवतीत्यर्थः । यथा—चुक्षावयिषति, ऊर्णुनावयिषति, शुश्रावयिषति, पुस्फारयिषति । अत्र **चिस्फुरोर्णा**वित्योकारस्यात्त्वम् । अत्र च यद्यपि खयूशेषे कृतेऽभ्यासस्य शरादित्वं नास्ति, तथाप्यभ्याससंज्ञाप्रवृत्तिकालेऽस्ति ॥ एतेष्वन्तरङ्गत्वात्प्रागेव द्विर्वचनाद्वृद्ध्यावादेशयोः प्रवर्तनादिवर्णान्ततायामभ्यासस्य प्राप्तायामुत्वं विधीयते ॥

(उद्द्योतः) **स्थानिवद्भाव एव ज्यायानिति ।** अयं भावः—अयं पूर्वविप्रतिषेधोऽन्तरङ्गाणां बाधको न वा । नाद्यः, बिभवनीयिषतीत्याद्यसिद्ध्यापत्तेः । किंचष्टानिष्टविवेकस्य लक्षणैकचक्षुष्कैर्दुर्ज्ञेयत्वेन सर्वत्रैव पूर्वविप्रतिषेधे वचनस्यावश्यकत्वेनेह नित्यान्तरङ्गबाधाय सुतरां वचनावश्यकत्वेन च सूत्रमतापेक्षया लाघवमिति ॥ अन्त्ये दूषणमाह—**औदोदादेशस्येति ।** अत्र समानाधिकरणबहुव्रीह्यङ्गीकारे चुक्षावयिषतीत्यादौ दोषः ॥ स्थानिवत्त्वं त्वल्विधित्वान्नेत्यत आह—**औदोतोरादेशो यस्मिन्निति ।** इदमेव ज्ञापकमन्तरङ्गाणामिदमबाधकमिति न बिभवनीयिषतीत्यादौ दोषः ॥ अत्र तन्नीत्वंशोऽपि पूरणीयः । अन्यथा दिद्वर्नायिषतीत्यादौ अनेनोत्वापत्तिः । तत्र कृते तु निर्दिष्टपरिभाषयाऽनेकव्यवधानान्न तत्र दोषः । एकणिज्व्यवधानं तु येन नाव्यवधानन्यायेन सह्यत एव ॥ नन्विदं वचनं ओः सौप्राण्णिचि चङि सनि च 'अर्जोत्नवत्-जिनावयिषति' इत्यादौ अतिव्याप्तम् । न च चकार एव पाठ्यः । गुरवुभ्यां णिचि चङि सनि वा 'अजूगवत्' इत्यादौ दोषापत्तेरिति चेन्न । *ओर्न*त्यस्यापि वाच्यत्वात् ॥ औदोतोः किम् ? चिखादयिषति ॥ किमादि किम् ? बिभावयिषतीत्यादि ॥ यद्यपि 'छो छेदने-चिच्छावयति' इत्यत्रैतदतिप्रसक्तम्, तथापि औत्साहचर्यादोकारोऽपि लाक्षणिक एव गृह्यते, तत्राऽऽदेशो वा औदादेशसाहचर्याद् अत्रैव गृह्यत इति न दोषः ॥ **ऊर्णुनावयिषतीति ।** यद्यपि पूर्वत्रासिद्धीयमद्विर्वचने इत्यस्यानित्यतया नुशब्दस्यैव द्वित्वेनाभ्याससंज्ञाप्रवृत्तिकाले द्वादित्वाभावः, तथाऽपि द्वित्वे कृतेऽपि द्वित्वनिष्पन्नस्य कार्ये कर्तव्ये पूर्वत्रासिद्धीयस्यासिद्धत्वाभावबोधनात्तत्रानित्यत्वकल्पने मानाभावाच्चैतत्प्रवृत्तिकाले द्वादित्वमस्त्येवेति बोध्यम् ॥ **अभ्याससंज्ञाप्रवृत्तिसमय इति ।** एवं चाभ्याससंज्ञाप्रवृत्तिसमये परिनिष्ठितरूपे वा यत्र चुड्डुतुशरादित्वं तत्रास्य प्रवृत्तिरिति भावः ॥ तत्रान्त्योदाहरणं-चुक्षावयिषतीत्यादि । नहि तत्राद्यकाले तत्वं, 'क्षु' इति कवर्गादित्वात्-इत्याहुः ॥

(उत्ववादिन आक्षेपभाष्यम्)

ननु च त्वयाऽपि इत्वं वक्तव्यम् ॥

(प्रदीपः) **ननु च त्वयापीति । ओः पुयण्ज्यिति** ज्ञापनार्थमवश्यं वाच्यमित्यर्थः । उत्ववादी तु **ओः पुयण्जीति** न पठति, **सन्यत इ**तीत्वस्य सिद्धत्वात् ॥

(उद्द्योतः) ननु णेर्द्वित्वनिमित्तत्वाभावेन स्थानिवत्त्वाभावाद् बिभावयिषतीत्यादि सिद्धमिति 'त्वयाऽपि' इत्ययुक्तमत आह—ओः पुयण्ज्यिति । चुक्षावयिषतीत्यादिसिद्ध्यर्थमित्यर्थः ॥

(इत्ववादिनो लाघवभाष्यम्)

परार्थं मम भविष्यति-"सन्यतः" इद्भवतीति ॥

(प्रदीपः) **परार्थमिति ।** इत्वार्थम् । प्रसङ्गात्तु ज्ञापकम् । त्वया त्वपूर्वमुत्वं वक्तव्यमित्यर्थः ॥

(उद्द्योतः) परार्थमित्यत्र परशब्देन ज्ञापकापेक्षया परमित्वं विवक्षितमित्याह—इत्वार्थमिति । द्विर्वचनेऽचीति स्थानिवत्त्वात् पिपविषते पिपविषतीत्यर्थमित्यर्थः ॥ **प्रसङ्गादिति ।** वर्णप्रत्याहारजग्रहादित्यर्थः ॥ **सन्यत इद्भवतीति** विहितमित्वमिहानुवर्तमानं परार्थं भविष्यतीति भाष्येऽन्वयः ॥ तत्र सन्यत इत्यभिधानं स्वरूपेणेत्वमपूर्वं न भवतीति प्रदर्शनार्थं, तद् ध्वनयन्नाह—अपूर्वमुत्वमिति ॥

(उत्ववादिनो गौरवपरिहारभाष्यम्)

ममापि तर्ह्युत्वं परार्थं भविष्यति-"उत्परस्यातः, ति च" इति ॥

(प्रदीपः) **ममापीति ।** उत्वमप्यन्यार्थं वक्तव्यम् । तदेवाधिकविषये उपजीव्यत इत्यर्थः । तत्रायं न्यासः—'**उत्परस्यातः' 'ति च' 'औदोदादेशस्य चुड्डुतुशरादेः'** इति । अभ्यासस्येति वर्तते ॥

(उद्योतः) अपूर्वत्वतदभावमात्रेण वैषम्यमस्याभिप्रेतमिति मन्वानस्तद्विघटयितुमाह परः—ममापि तर्ह्युत्वमिति ॥ तद्याचष्टे—उत्वमपीति ॥

(इत्ववादिभाष्यम्)

इत्वमपि त्वया वक्तव्यम् । यत्समानाश्रयं तदर्थम्—उतिपणिषते, संयियविषतीत्येवमर्थम् ॥ तस्मात्स्थानिवदित्येष एव पक्षो ज्यायान् ॥ द्विर्वचनेऽचि ॥ ५९ ॥

इति श्रीमद्भगवत्पतञ्जलिविरचिते व्याकरणमहाभाष्ये प्रथमस्याध्यायस्य प्रथमे पादे अष्टममाह्निकम् ॥

(प्रदीपः) इत्वमपीति । यत्रान्तरङ्गत्वं नास्ति समानाश्रयत्वात् । एवतेश्चैतश्च सनि 'सिपूङ्रञ्ज्वशां सनि' 'सनीवन्तर्ध-' इति चेटि कृते परत्वाद्गुणः । पूर्वविप्रतिषेधादवादेशात् पूर्वं द्विर्वचनाद्वा नीत्वं वक्तव्यम् । तथा जिजावयिषतीत्यत्रेत्वविधानार्थं वक्तव्यम् ॥ तस्मादिति । नन्वसत्यस्मिन् सूत्रे ओः पुयण्ज्यपरे इति ज्ञापकमेवं समर्थयिष्यते—अन्तरङ्गो णिलोपश्च विधिर्द्विर्वचनेन प्रतिबध्यत इति तत्र द्विर्वचने कृते यथाप्राप्तं भविष्यति ॥ तदयुक्तम् । यदि सामान्येन ज्ञापकमाश्रीयते, अचिकीर्तदित्यत्रापि पूर्वं द्विर्वचनप्रसङ्गादनिष्टरूपप्राप्तिः ॥ अथ तुल्यजातीयापेक्षं ज्ञापकं व्याख्यायते, यथोक्तं भाष्यकारेण, तथा सति चक्रतुरित्यादि न सिध्यतीति सूत्रमेव कर्तव्यम् । यत्तु तेन न सिध्यति तदर्थं ज्ञापकमाश्रयणीयं तुल्यजातीयापेक्षमिति सर्वेष्टलक्ष्यसिद्धिः ॥ ५९ ॥

इत्युपाध्यायजैयटपुत्रकैयटकृते महाभाष्यप्रदीपे प्रथमस्याध्यायस्य प्रथमे पादेऽष्टममाह्निकम् ॥

(उद्योतः) नापूर्वत्व-तदभावमात्रेण वैषम्यमभिप्रेतम्, किन्तु गौरवतदभावाभ्यामिति दर्शयितुं भाष्ये—इत्वमपीति ॥ तदुपपादयति—यत्रेति । गुणावादेशयोरिति शेषः ॥ वक्तव्यमिति । 'णौ' इति वक्तव्यमित्यर्थः ॥ नन्वसतीति । असत्यपीत्यर्थः ॥ यदीति । लघुपरत्वाभावेन सन्वद्भावाभावोऽचिकीर्तदित्यत्र दोषः, दिदवनीयिषतीत्यादावपि दोषो बोध्यः ॥ अथ तुल्येति । अवर्णपरत्वं यत्राभ्यासोत्तरखण्डावर्णस्य अभ्याससंज्ञाप्रवृत्तिसमये परिनिष्ठितरूपे वा, तत्र द्विर्वचनेनान्तरङ्गनिले बाध्येते इत्यर्थः ॥ चक्रतुरिति । दिदवनीयिषतीत्याद्यसिद्धिरित्यपि बोध्यम् ॥ ५९ ॥

इति श्रीशिवभट्टसुतसतीगर्भजनागोजीभट्टकृते भाष्यप्रदीपोद्योते प्रथमाध्यायस्य प्रथमे पादे अष्टममाह्निकम् ॥

अथ प्रथमाध्यायस्य प्रथमपादे नवममाह्निकम् ॥

(५५ लोपसंज्ञासूत्रम् ॥ १ । १ । ९ आ. १ ॥)

अदर्शनं लोपः ॥ १ । १ । ६० ॥

(अनिष्टापत्तिनिराकरणम्)

(आक्षेपभाष्यम्)

अर्थस्य संज्ञा कर्तव्या । शब्दस्य माभूदिति ॥

(प्रदीपः) अदर्शनं लोपः ॥ ६० ॥ अर्थस्येति । स्वं रूपमिति वचनाच्छब्दस्यैव संज्ञा प्राप्नोतीति भावः ॥

(उद्योतः) अदर्शनं लोपः ॥ ६० ॥ नन्वपत्यादिवदर्थपरोऽदर्शनशब्द इति सिद्धैवार्थस्य संज्ञेत्यत आह—स्वमिति ॥

(आक्षेपभाष्यम्)

इतरेतराश्रयं च भवति ॥

का इतरेतराश्रयता ?

सतोऽदर्शनस्य संज्ञया भवितव्यम्, संज्ञया चादर्शनं भाव्यते, तदेतदितरेतराश्रयं भवति । इतरेतराश्रयाणि कार्याणि च न प्रकल्पन्ते ॥

(प्रदीपः) इतरेतराश्रयमिति । विधिप्रदेशेष्वेतच्चोद्यम्, नानुवादे—चादिलोपे विभाषेत्यादौ ॥

(उद्योतः) नानुवादे इति । तत्र हि न संज्ञाकृतोऽभाव इत्यर्थः ॥

(समाधाने भाष्यवार्तिकम्)

* ॥ लोपसंज्ञायामर्थसतोरुक्तम् ॥ *

किमुक्तम् ?

अर्थस्य तावदुक्तम्-* इतिकरणोऽर्थनिर्देशार्थः* इति ॥

सतोऽप्युक्तम्—* सिद्धं तु नित्यशब्दत्वात्* इति । नित्याः शब्दाः । नित्येषु शब्देषु सतोऽदर्शनस्य संज्ञा क्रियते, न संज्ञयाऽदर्शनं भाव्यते ॥

(प्रदीपः) इतिकरण इति । इहापि स एवानुवर्तते ॥ 'लोपः' इत्यन्वर्थसंज्ञाविज्ञानाद्वाऽर्थस्य संज्ञा, न शब्दस्य ॥

(उद्योतः) भाष्ये—उक्तमिति । नचेति विभाषेत्यत्रेत्यर्थः ॥ असंबद्धपदव्यवायान्नानुवृत्तिरत आह—लोप इतीति । तदर्थान्वययोग्यताया अर्थे एव सत्त्वात् अदर्शनशब्दस्य तादृशान्वर्थसंज्ञाकरणे फलाभाव इति भावः ॥ 'प्रसक्तादर्शनस्य' इत्यर्थलाभार्थे स्थानेपदस्येवास्याप्यनुवृत्तिः सुलभा, 'लुप्लृ छेदने' इति धात्वर्थानुसारेणान्वर्थत्वासंभवादिति तु भाष्यतात्पर्यम् ॥ अभावो लोप इत्यवसानसंज्ञासूत्रभाष्योक्तेरदर्शनशब्देन तत्समनियतो वर्णाभाव एवात्रेति बोध्यम् ॥ स्वंरूपमित्यस्य प्रत्याख्याने तदनुवृत्तिं विनाऽपि सिद्धिरिति बोध्यम् ॥

(२७२ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ सर्वप्रसङ्गस्तु सर्वस्यान्यत्रादृष्टत्वात् ॥ * ॥

(भाष्यम्)

सर्वप्रसङ्गस्तु भवति । सर्वस्यादर्शनस्य लोपसंज्ञा

प्राप्नोति ॥

किं कारणम् ?

'सर्वस्यान्यत्रादृष्टत्वात्' । सर्वो हि शब्दो यो यस्य प्रयोगविषयः, स ततोऽन्यत्र न दृश्यते । त्रपु-जतु-इत्यत्राणः "अदर्शनं लोपः" इति लोपसंज्ञा प्राप्नोति ॥

(प्रदीपः) **सर्वप्रसङ्गस्त्विति** । यदि स्वभावतोऽप्रयुक्तस्यान्वाख्यानमात्रं क्रियते, तदा सर्वस्य स्वविषयादन्यत्राप्रयोगादस्त्यदर्शनमिति लोपसंज्ञाप्रसङ्गः ॥

(उद्द्योतः) नित्यशब्दाश्रयणे इतरेतराश्रयपरिहारेऽप्ययं दोष इत्याह—यदीति ॥

(भाष्यम्)

तत्र को दोषः ?

(३७३ आक्षेपवार्तिकम् ॥ २ ॥)

॥ * ॥ तत्र प्रत्ययलक्षणप्रतिषेधः ॥ * ॥

(भाष्यम्)

तत्र प्रत्ययलक्षणं कार्यं प्राप्नोति, तस्य प्रतिषेधो वक्तव्यः । "अचो ञ्णिति" इति वृद्धिः प्राप्नोति ॥

(आक्षेपबाधकभाष्यम्)

नैष दोषः । ञ्णित्यङ्गस्याचो वृद्धिरुच्यते । यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गं भवति । यस्माच्चात्र प्रत्ययविधिः, न तत् प्रत्यये परतः । यच्च प्रत्यये परतः, न तस्मात्प्रत्ययविधिः ॥

(प्रदीपः) **ञ्णित्यङ्गस्येति** । अङ्गसंज्ञा च विधानप्रतिबद्धा । न चात्र प्रत्ययस्य ञ्णितो विधानम् ॥ **यस्माच्चेति** । त्रपुशब्दात्सोर्विधानम् ॥ **न तत्प्रत्यय इति** । ञ्णिति वृद्धिनिमित्त इत्यर्थः ॥ **यच्चेति** । त्रुशब्दे ॥ **न तस्मादिति** । तस्मात्त्रपुशब्दात्सोरन्यस्याणो विधानं नास्तीत्यर्थः ॥

(उद्द्योतः) अत्र प्रत्ययो नाणित्याह— सोरिति ॥ ञ्णिति वृद्धिनिमित्ते इति । अङ्गसंज्ञासूत्रे प्रत्यासत्त्या प्रत्ययपदार्थयोरैक्याश्रयणाद् वृद्धिविधौ ञ्णित्प्रत्ययनिरूपिताङ्गग्रहणाच्चेति भावः ॥

(आक्षेपसाधकभाष्यम्)

क्विपस्तर्ह्यदर्शनम् । तत्र "अदर्शनं लोपः" इति लोपसंज्ञा प्राप्नोति ॥

तत्र को दोषः ?

'तत्र प्रत्ययलक्षणप्रतिषेधः' । तत्र प्रत्ययलक्षणं कार्यं प्राप्नोति, तस्य प्रतिषेधो वक्तव्यः । ह्रस्वस्य पिति कृति तुग्भवति-इति तुक् प्राप्नोति ॥

(प्रदीपः) अनाङ्गं कार्यं चोदयति—**क्विप इति** । 'त्रपु' इत्यत्र क्विपोऽदर्शनमस्ति स च कृदिति तुक्प्रसङ्गः ॥

(३७४ समाधानवार्तिकम् ॥ ३ ॥)

॥ * ॥ सिद्धं तु प्रसक्तादर्शनस्य लोपसंज्ञित्वात् ॥ * ॥

(भाष्यम्)

सिद्धमेतत् ॥

कथम् ?

प्रसक्तादर्शनं लोपसंज्ञं भवतीति वक्तव्यम् ॥

(प्रदीपः) **सिद्धं त्विति** । शास्त्रादर्थाद्वा प्रसक्तस्य यददर्शनं तल्लोपसंज्ञं भवति ॥ स्थानेग्रहणमिहाप्यनुवर्तते । स्थानं च प्रसङ्गः । तेन प्रसङ्गे यददर्शनमिति लभ्यते ॥

(उद्द्योतः) 'चादिलोपे' इति संग्रहायाह—अर्थाद्वेति । एकवचनमुत्सर्गत इत्यादिशास्त्रमर्थापेक्षं विभक्तिप्रसञ्जकम् । अर्थोऽप्येकत्वादिर्विवक्षित एकवचनादिप्रसञ्जक इति बोध्यम् ॥ ननु कथं 'प्रसक्तस्य' इति लभ्यतेऽत आह—स्थान इति । न च पित्कृता प्रकृत्याक्षेपेणापि तुग्वारयितुं शक्यः । आक्षेपे-आक्षिप्तस्य शाब्देऽन्वये च मानाभावात् । अत्र चेदमेव भाष्यं मानम् । किंचानुपपद्यमानेन स्वोपपादकमाक्षिप्यते, यथा–पीनत्वेन रात्रिभोजनम् ॥ न चैवं प्रकृते । न हि तत्सूत्रे आक्षेपं विना पित्कृत्प्रत्ययानुपपत्तिरस्ति । नापि तदाक्षेपेण तदुपपत्तिः । नापि प्रत्ययग्रहणे यस्मात्स विहितस्तदादेरित्युपस्थितिः । अनियमप्रसक्त्यभावेन नियमफलाभावात्तस्या अनुपस्थितेरित्यावेदितम् । किंचात्रैव प्रकृतिं विना प्रत्ययस्थानदर्शनेन व्यभिचारात्तदाक्षेपासंभव इति दिक् ॥ यत्तु ग्रामाधिकरणिका स्थितिरित्यर्थके 'ग्रामे तिष्ठति' इति वाक्ये ल्यब्लोप इति पञ्चम्यापत्तिवारणाय प्रसक्तस्येत्यावश्यकमिति ॥ तन्न । तेन प्रत्यासत्त्या ल्यबन्तार्थककर्माधिकरणयोरेव पञ्चमीविधानेनाप्रसङ्गः । तदर्थे स्थित्यापत्तिः पञ्चम्या इत्यलम् ॥

(आक्षेपभाष्यम्)

यदि प्रसक्तादर्शनं लोपसंज्ञं भवतीत्युच्यते, ग्रामणीः-सेनानीः, अत्र वृद्धिः प्राप्नोति ॥

(प्रदीपः) **ग्रामणीरिति** । अर्थोपपदधातुसंनिधानादर्थाच्छास्त्राच्चाणः प्रसङ्गोऽस्तीति भावः ॥

(उद्द्योतः) **अर्थादिति** । कर्तृलक्षणादित्यर्थः ॥ **शास्त्रात्**—कर्मण्यणित्यतः ॥ **अणः प्रसङ्ग इति** । यस्मात्प्रत्ययविधिरित्यत्र विधिः-प्रसङ्ग एव विवक्षित इत्यङ्गत्वमस्तीत्यभिमानः ॥

(समाधानभाष्यम्)

प्रसक्तादर्शनं लोपसंज्ञं भवति षष्ठीनिर्दिष्टस्य ॥

(प्रदीपः) **षष्ठीनिर्दिष्टस्येति** । षष्ठीग्रहणमप्यनुवर्तते ॥

(उद्द्योतः) **षष्ठीग्रहणमिति** । तच्च षष्ठ्यन्तं वैयधिकरण्येनादर्शनान्वयीति बोध्यम् ॥

(प्रसक्तादर्शनवादिन आक्षेपभाष्यम्)

यदि षष्ठीनिर्दिष्टस्येत्युच्यते "चाहलोप एवेत्यवधारणम्" "चादिलोपे विभाषा" अत्र लोपसंज्ञा न प्राप्नोति ॥

(प्रदीपः) **चादिलोप इति** । ततश्च **शुक्ला व्रीहयो भवन्ति श्वेता गा आज्याय दुहन्तीति** निघातविकल्पो न स्यात् ॥

(षष्ठीनिर्दिष्टवादिन आक्षेपभाष्यम्)

अथ प्रसक्तादर्शनं लोपसंज्ञं भवतीत्युच्यमाने कथमेवैतत् सिध्यति ?

(प्रदीपः) **अथेति** । अत्राऽपि चादीनां शास्त्रान्नास्ति

प्रसङ्गः ॥

(उद्योतः) अत्रापीति । शास्त्रतः प्रसक्तिरेवाभिमतेति चोद्यमिति भावः ॥

(प्रसक्तादर्शनवादिनः समाधानभाष्यम्)

को हि शब्दस्य प्रसङ्गः ?

यत्र गम्यते चार्थः, न च प्रयुज्यते ॥

(उद्योतः) अर्थतोऽपि प्रसक्तिर्गृह्यत इत्युत्तरम् ॥

(उपसंहारभाष्यम्)

अस्तु तर्हि प्रसक्तादर्शनं लोपसंज्ञं भवतीत्येव ॥

(आक्षेपस्मारणभाष्यम्)

कथं ग्रामणीः-सेनानीः ?

(समाधानभाष्यम्)

योऽसावणः प्रसङ्गः क्विपाऽसौ बाध्यते ॥ अदर्शनं लोपः ॥ ६० ॥

(प्रदीपः) क्विपाऽसौ बाध्यत इति । 'सत्सूद्विष-' इति क्विपो विधानादणोऽत्र प्रसङ्गाभावः ॥ ६० ॥

(उद्योतः) अणोऽत्रेति । परिहृत्य चापवादविषयमिति न्यायेन प्रसङ्ग एव नास्तीति भावः ॥ ६० ॥

(५६ लुक्श्लुलुप्संज्ञासूत्रम् ॥ १ । १ । ९ आ. २)

प्रत्ययस्य लुक्श्लुलुपः ॥ १ । १ । ६१ ॥

(प्रत्ययपदप्रयोजनम्)

(आक्षेपभाष्यम्)

प्रत्ययग्रहणं किमर्थम् ?

(प्रदीपः) प्रत्ययस्य० ॥ ६१ ॥ प्रत्ययग्रहणमिति । लुगादिविधौ क्वचित्प्रत्ययः साक्षान्निर्दिश्यते, क्वचिदनुवर्तते, क्वचित्सामर्थ्यात्प्रतीयत इति प्रश्नः ॥

(उद्योतः) प्रत्ययस्य० ॥ ६१ ॥ ननु लुगादिविधौ प्रत्ययादर्शनविधिर्यथा स्यादित्यर्थं प्रत्ययस्येतीत्यत आह—लुगादीति ॥ साक्षादिति । लुगणिञोरित्यादौ ॥ क्वचिदिति । यथा लुग्वा-दुहेत्यादौ 'क्सस्य' इति ॥ क्वचिदिति । वक्ष्यमाणसूत्रेषु वक्ष्यमाणयुक्तिभिरित्यर्थः ॥

(समाधाने भाष्यवार्तिकम् ॥)

॥ लुमति प्रत्ययग्रहणमप्रत्ययसंज्ञाप्रतिषेधार्थम् ॥

(भाष्यम्)

लुमति प्रत्ययग्रहणं क्रियते, अप्रत्ययस्यैताः संज्ञा मा भूवन्निति ॥

(प्रदीपः) अप्रत्ययस्येति । अविद्यमानः प्रत्ययो यस्मिन्नदर्शने इति तदप्रत्ययम् ॥

(उद्योतः) नन्वदर्शनस्येमाः संज्ञा इति अप्रत्ययस्यैता इत्यनुपपन्नमत आह—अविद्यमान इति । प्रतियोगिविशेषणत्वेनेति शेषः ॥ वस्तुतोऽवसानसंज्ञासूत्रे वक्ष्यमाणरीत्या प्रत्ययाभावस्यैवेमाः संज्ञा इति भाष्याभिप्रायः ॥

(भाष्यम्)

किं प्रयोजनम् ?

(प्रयोजने भाष्यवार्तिकम्)

॥ प्रयोजनं तद्धितलुकि कंसीयपरशव्ययोर्लुकि च गोप्रकृतिनिवृत्त्यर्थम् ॥

(भाष्यम्)

तद्धितलुकि गोनिवृत्त्यर्थम् । कंसीयपरशव्ययोश्च लुकि प्रकृतिनिवृत्त्यर्थम् । "लुक्तद्धितलुकि" इति गोरपि लुक् प्राप्नोति, प्रत्ययग्रहणान्न भवति ॥ "कंसीयपरशव्ययोर्यञञौ लुक् च" इति प्रकृतेरपि लुक् प्राप्नोति, प्रत्ययग्रहणान्न भवति ॥

(प्रदीपः) गोरपीति । पञ्चेन्द्र इत्यादौ तु निर्दिश्यमानस्यादेशा भवन्तीति वचनात् स्त्रीप्रत्ययस्यैव लुक् भविष्यति, न तदन्तस्य । गोरतद्धितलुकीत्यत्र गोर्लुकि कृते पञ्चगुरित्यादौ गोशब्दान्तत्वाभावात्समासान्ताप्राप्तावतद्धितलुकीति प्रतिषेधोऽनर्थकः स्यादिति चेत् ॥ कृते समासान्ते लुक् स्यादित्यर्थवानेव प्रतिषेधः ॥ ननु स्वभावतोऽप्रवृत्तस्यादर्शनं लुक्संज्ञम् । न च तत्र गोशब्दस्य स्वभावतोऽप्रवृत्तिः ॥ नैष दोषः । शास्त्रानुसारिभिरस्यार्थस्य दुर्ज्ञानत्वात् ॥ प्रकृतेरपीति । समुदायस्य षष्ठीनिर्देशात् ॥

(उद्योतः) भाष्ये—गोरपीति । गोस्त्रियोरिति समुदायानुवृत्तेरिति भावः ॥ ननु गोस्त्रियोरित्यत्र 'स्त्री' इति स्वरितगुणयुक्तमिति स्त्रियामित्यधिकारविहितप्रत्ययग्रहणेन तदन्तग्रहणात् प्रत्ययान्तस्य लुक् स्यादिति तद्धितलुकि तन्निवृत्त्यर्थत्वमपि कुतो नोक्तम् ? अत आह—पञ्चेन्द्र इति ॥ गोनिवृत्तिः प्रत्ययग्रहणं विनाऽपि सिध्यतीति शङ्कते—गोरिति । पञ्चगुरित्यत्र क्रीतार्थेठकोऽध्यर्धेति लुक् ॥ कृते इति । परत्वादिति भावः । अन्तरङ्गानपीति न्यायस्तु अन्तरङ्गनिमित्तविनाशकप्रत्ययलुग्विषय इति तात्पर्यम् ॥ न च समासान्ते तेन व्यवधानात्कथं लुक्, गोरित्यनुवृत्तिसामर्थ्येन लुक्प्राप्तेरिति बोध्यम् ॥ नित्यशब्दान्वाख्यानाभिप्रायेण शङ्कते—नन्विति ॥ समुदायस्येति । यस्येति चेत्यकारलोपे सिद्धे लुग्विधानसामर्थ्येन सर्वादेशः स्यादित्यर्थः ॥

(प्रत्याख्यानभाष्यम्)

गोनिवृत्त्यर्थेन तावन्नार्थः ॥

(प्रत्याख्यानसाधकं भाष्यवार्तिकम्)

॥ योगविभागात् सिद्धम् ॥

(भाष्यम्)

योगविभागः करिष्यते—"गोरुपसर्जनस्य" गोऽन्तस्य प्रातिपदिकस्योपसर्जनस्य ह्रस्वो भवति ॥ ततः "स्त्रियाः" स्त्रीप्रत्ययान्तस्य प्रातिपदिकस्योप-

सर्जनस्य ह्रस्वो भवति ॥ ततो "लुक्तद्धितलुकि" इति । स्त्रिया इति वर्तते । गोरिति निवृत्तम् ॥

(प्रदीपः) योगविभागादिति । एकयोगनिर्दिष्टानामप्येकदेशानुवृत्तिरित्येतत् प्रकारान्तरेण प्रतिपाद्यते ॥

(उद्द्योतः) ननु योगविभागे सूत्रभेदः कृतः स्यादत आह—एकयोगेति ॥ प्रकारान्तरम्—योगविभागरूपम् ॥

(प्रत्याख्यानसाधकं भाष्यवार्तिकम्)

॥ कंसीयपरशव्ययोर्विशिष्टनिर्देशात् सिद्धम् ॥

(भाष्यम्)

कंसीयपरशव्ययोरपि विशिष्टनिर्देशः कर्तव्यः । कंसीयपरशव्ययोर्यञञौ भवतः, छयतोश्च लुग्भवतीति ॥

(प्रदीपः) विशिष्टनिर्देशादिति । छयतावेवात्र निर्देष्टव्यावित्यर्थः ॥

(उद्द्योतः) छयताविति । कंसाद्-प्राक्क्रीताच्छः । परशोः—उगवादिभ्यो यत् ॥

(विशिष्टनिर्देशावश्यकताभाष्यम्)

स चावश्यं विशिष्टनिर्देशः कर्तव्यः । क्रियमाणेऽपि वै प्रत्ययग्रहणे उकारसशब्दयोर्मा भूदिति । 'कमेः सः' कंसः, परान् शृणातीति परशुरिति ॥

(उद्द्योतः) कंसे-कमेः सः । परशौ—आङ्परयोः खनिशॄभ्यां डिदित्युप्रत्ययः ॥

(विशिष्टनिर्देशावश्यकताबाधकभाष्यम्)

नैष दोषः । उणादयोऽव्युत्पन्नानि प्रातिपदिकानि ॥

(प्रदीपः) उणादय इति । अतः कृकमिकंसकुम्भेति कंसशब्दस्य भेदेनोपादानात् क्वचिदुणादयो व्युत्पत्तिकार्यं न लभन्त इत्यर्थः । यञञोस्तु विधानसामर्थ्याल्लुगभावः ॥

(उद्द्योतः) अतः कृ इति । धातौ सप्तमीनिर्दिष्टे तदादिग्रहणात् कमिग्रहणेनैव सिद्धे—इति शेषः ॥ कंसेस्तु 'कंसः' इति न रूपम्, अनभिधानादिति भावः ॥ अत एव कमेः सः कंस इति भाष्ये उक्तम् ॥ नन्वेवमपि विशिष्टनिर्देशाभावे यञञोरपि लुक् स्यादत आह—यञञोरिति । विकारावयवार्थप्रतीतये औत्सर्गिकाण एव लुकं विदध्यात् ॥ न च यञञ्लुकां सामर्थ्याद्विकल्पोऽस्तु । वेत्यनुक्तिस्तु यञञ्भ्यां मुक्ते औत्सर्गिकाणः श्रवणाभावायेति वाच्यम् ॥ यञञ्लुकामेककालप्रतीतानामुद्देश्यविधेयभावासंभवात् ॥ ईदृग्लुक्तौ तु द्वैपेयादौ तु अनद्यतन इत्यादिनिर्देशाद्वावयभेदाशङ्काकारः । किं च कंसीयपरशव्ययोरिति षष्ठीनिर्देशादपि न यञञोर्लुक्, अन्यथा पञ्चम्यैव निर्दिशेदिति भावः ॥

(उपसंहारभाष्यम्)

स एषोऽनन्यार्थो विशिष्टनिर्देशः कर्तव्यः, प्रत्ययग्रहणं वा कर्तव्यम् ॥

(प्रदीपः) स एषोऽनन्यार्थ इति । प्रकृतिनिवृत्त्यर्थ एव, न तु प्रत्ययान्तरनिवृत्त्यर्थोऽपीत्यर्थः ॥

(उद्द्योतः) प्रकृतीति । प्रकृतिभिन्यतिरिक्तप्रत्ययान्तरवाची अन्यशब्दः । तेन नञः समासे प्रकृतिरन्यत इत्याशयः ॥

(प्रत्याख्याने भाष्यवार्तिकम्)

॥ उक्तं वा ॥

(भाष्यम्)

किमुक्तम् ?

* ङ्याप्प्रातिपदिकग्रहणमङ्गभपदसंज्ञार्थं यच्छयोश्च लुगर्थम् * इति ॥

(उद्द्योतः) भाष्ये—छयाविति । 'प्रातिपदिकात्परस्य लुक्' इत्यर्थे यञञोर्विधानसामर्थ्याल्लुगभावे उभयोः प्रातिपदिकात्परत्वाभावेन परिशेषात् कंसीयादवयवप्रातिपदिकात्परयोः छयतोरेव लुगित्यर्थः ॥

(१७५ प्रयोजनवार्तिकम् ॥ १ ॥)

॥ * ॥ षष्ठीनिर्देशार्थं तु ॥ * ॥

(भाष्यम्)

षष्ठीनिर्देशार्थं तर्हि प्रत्ययग्रहणं कर्तव्यम् । षष्ठीनिर्देशो यथा प्रकल्पेत ॥

(१७६ प्रयोजनसाधकं वार्तिकम् ॥ २ ॥)

॥*॥ अनिर्देशो हि षष्ठ्यर्थाप्रसिद्धिः ॥*॥

(भाष्यम्)

अक्रियमाणे हि प्रत्ययग्रहणे षष्ठ्यर्थस्याप्रसिद्धिः स्यात् ॥

कस्य ?

स्थानेयोगत्वस्य ॥

(प्रदीपः) षष्ठीनिर्देशार्थं त्विति । विशिष्टस्य षष्ठ्यर्थस्य स्थानेयोगत्वनिर्देशार्थमित्यर्थः ॥ असति प्रत्ययस्येत्येतस्मिन् यः कश्चिदानन्तर्यादिः संबन्धः स्यात् । ततश्च जनपदे लुबिति पञ्चालाः शोभना इत्यादौ जनपदवाचिनोऽनन्तरस्य शोभनादेरपि लुप् स्यात् ॥

(उद्द्योतः) विशिष्टेति । जनपदार्थकप्रत्ययसंबन्धिन इत्यर्थः ॥ शोभनाः पञ्चाला इत्यादौ इति पाठ उचितः ॥ अनन्तरस्येति । अव्यवहितस्येत्यर्थः । जनपदार्थवाचके शब्दे सति तदनन्तरस्य लुबित्यर्थ इति भावः ॥

(प्रत्याख्यानसाधकमाक्षेपभाष्यम्)

क पुनरिह षष्ठीनिर्देशार्थेनार्थः प्रत्ययग्रहणेन । यावता सर्वत्रैव षष्ठ्युच्चार्यते—अणिञोः, तद्राजस्य, यञञोः, शप इति ?

(समाधानभाष्यम्)

इह न काचित् षष्ठी—"जनपदे लुप्" इति ॥

(समाधानबाधकभाष्यम्)

अत्रापि प्रकृतं प्रत्ययग्रहणमनुवर्तते ॥

क्व प्रकृतम् ?

"प्रत्ययः, परश्च" इति ॥

(उद्योतः) भाष्ये—प्रकृतमिति । अत एव लवणाल्लुगित्यत्र प्रकृतठक एव लुगिति बोध्यम् ॥

(समाधानसाधकभाष्यम्)

तद्वै प्रथमानिर्दिष्टम् । षष्ठीनिर्दिष्टेन चेहार्थः ॥

(समाधानबाधकभाष्यम्)

"ङ्याप्प्रातिपदिकात्" इत्येषा पञ्चमी प्रत्यय इति प्रथमायाः षष्ठीं प्रकल्पयिष्यति "तस्मादित्युत्तरस्य" इति ॥

(समाधानसाधकभाष्यम्)

प्रत्ययविधिरयम् । न च प्रत्ययविधौ पञ्चम्यः प्रकल्पिका भवन्ति ॥

(समाधानबाधकभाष्यम्)

नायं प्रत्ययविधिः । विहितः प्रत्ययः प्रकृतश्चानुवर्तते ॥

(१७७ प्रयोजनवार्तिकम् ॥ ३ ॥)

॥ * ॥ सर्वादेशार्थं वा वचनप्रामाण्यात् ॥ * ॥

(भाष्यम्)

सर्वादेशार्थं तर्हि प्रत्ययग्रहणं कर्तव्यम् । लुक्श्लुलुपः सर्वादेशा यथा स्युः ॥

अथ क्रियमाणेऽपि प्रत्ययग्रहणे कथमिव लुक्श्लुलुपः सर्वादेशा लभ्याः ?

'वचनप्रामाण्यात् ।' प्रत्ययग्रहणसामर्थ्यात् ॥

(प्रदीपः) सर्वादेशार्थं वेति । षष्ठीनिर्देशार्थत्वं स्थितमेवेति वार्तिककारेण विकल्पार्थो वाशब्दः प्रयुक्तः ॥ आगस्त्यकौण्डिन्ययोरित्यत्र हि यदि लुगनुवर्तते, तदैकैकस्य त्रय आदेशाः । अथ नानुवर्तते, द्वावेवादेशौ विधीयेते । तदाऽगस्त्यादेशेन सर्वत्र भाव्यमिति 'आगस्तीयाश्छात्राः' इति न सिध्यति, अवृद्धत्वात् प्रकृतेः । 'प्रत्ययस्य' इति तूच्यमाने गोत्रेऽलुगचीति लुकि प्रतिषिद्धे संनियोगशिष्टत्वात् लुगभावादगस्त्यादेशाभावादागस्तीया इति सिध्यतीति षष्ठीनिर्देशार्थं प्रत्ययग्रहणम् ॥ भाष्यकारस्तु तदर्थे वाशब्दं व्याचक्षाणः षष्ठीनिर्देशार्थत्वं नेच्छति । स ह्येवं मन्यते—आगस्त्यकौण्डिन्ययोरित्यत्र यस्कादिभ्यो गोत्र इत्यतो गोत्रग्रहणमनुवर्तते, लुगिति च । तेनागस्त्यकौण्डिन्ययोर्यो गोत्रे विहितस्तस्य लुक् । परिशिष्टस्य तु प्रकृतिभागस्य यथासंख्यमगस्तिकुण्डिनचावादेशाविति सूत्रार्थः ॥ अथ क्रियमाणेऽपीति । अलोऽन्त्यस्येति वचनात् प्रत्ययस्य योऽन्त्यस्तस्यैव प्राप्नुवन्तीति भावः ॥ वचनप्रामाण्यादिति । प्रत्ययस्येति वचनसामर्थ्यादलोऽन्त्यस्येति बाध्यते । वचनप्रामाण्यादिति ब्रुवतो वार्तिककारस्यापि षष्ठीनिर्देशार्थत्वमनवस्थितम् । तदर्थत्वे हि प्रत्ययस्येत्यस्य चरितार्थत्वात्कथमलोऽन्त्यविधिर्बाध्यते ॥

(उद्योतः) वार्तिककृदभिमतषष्ठीनिर्देशार्थत्वमुपपादयति—आगस्त्येति ॥ त्रय इति । एवं च वैषम्याद्यथासङ्ख्याप्राप्तेरगस्तयोऽपि कुण्डिनाः, कुण्डिनाश्चागस्तयः स्युः, लुक्च ज्ञापकात्सर्वादेश इति विभक्तिमात्रं श्रूयेतेति भावः ॥ द्वावेवेति । तेन नोक्तापत्तिरिति भावः ॥ सर्वत्रेति । अणादिप्राग्दीव्यतीयविषयेऽपीति भावः ॥ अवृद्धत्वादिति । यद्यपि स्थानिवद्भावेन वृद्धत्वाच्छः सिध्यति, तथाप्यवृद्धत्वात्प्रकृतेः छस्य वृद्धयनिमित्तत्वाच्च आकारश्रवणं न स्यादिति भावः ॥ सन्नियोगशिष्टत्वादगस्त्यादेशाभावे प्रतिषेधप्रयुक्तलुगभावो हेतुः ॥ गोत्रे विहित इति । नन्वागस्त्यस्य गोत्रप्रत्ययान्तस्यैव ग्रहणम्, न त्वनन्तरापत्यप्रत्ययान्तस्येत्येतदर्थं तदनुवृत्तिः स्यात् । शिवादिभ्य इत्यत्रैव गोत्र इति निवृत्ते ऋष्यणसाधारणः अगस्त्यप्रकृतिप्रकृतिकऋष्यणन्त एवात्रागस्त्यः, न त्वगस्तिप्रकृतिकगर्गादियञन्तः, यञञोश्चेति लुका सिद्धत्वादिति चेन्न । कौण्डिन्यसाहचर्येणागस्त्यस्यापि गोत्रप्रत्ययान्तस्यैव ग्रहणात् । भाष्यमते गोत्रसंज्ञासूत्रपर्यन्तं गोत्राधिकारेण ऋष्यणन्तस्यापि तत्त्वाच्च ॥ वस्तुतो वार्तिककारस्यापीत्थमेव संमतमित्याह—प्रत्ययस्येति वचनेति ॥

(प्रयोजननिराकरणभाष्यम्)

एतदपि नास्ति प्रयोजनम् ॥ आचार्यप्रवृत्तिर्ज्ञापयति—लुक्श्लुलुपः सर्वादेशा भवन्तीति । यदयं—"लुग्वा दुहदिहलिहगुहामात्मनेपदे दन्त्ये" इति लोपे प्रकृते लुकं शास्ति ॥

(प्रदीपः) यदयमिति । विपर्ययस्तु न प्रकल्प्यते । अनुपसंजातविरोधत्वाल्लोपस्तावदन्त्यादेशः स्थितः, ततो लुगारभ्यमाणो यद्यन्त्यस्य स्याल्लोपानुवृत्त्यैव सिद्धत्वाल्लुकं न विदध्यात् ॥ विहितस्तु सर्वादेशत्वस्य ज्ञापकः संपद्यते ॥

(उद्योतः) सामर्थ्याल्लोपस्यैव सर्वादेशत्वं कुतो न कल्प्यत इत्यत आह—विपर्यय इति । न उपसंजातो विरोधो वैयर्थ्यशङ्कोद्भवो यस्य तस्मादित्यर्थः ॥

(१७८ प्रयोजनवार्तिकम् ॥ ४ ॥)

॥ * ॥ उत्तरार्थं तु ॥ * ॥

(भाष्यम्)

उत्तरार्थं तर्हि प्रत्ययग्रहणं कर्तव्यम् ॥

(प्रयोजनबाधकभाष्यम्)

क्रियते तत्रैव—"प्रत्ययलोपे प्रत्ययलक्षणम्" इति ॥

(प्रयोजनसाधकभाष्यम्)

द्वितीयं कर्तव्यम् । कृत्स्नप्रत्ययलोपे प्रत्ययलक्षणं यथा स्यात्, एकदेशलोपे मा भूदिति 'आघ्नीत' 'सं रायस्पोषेण ग्मीय' इति ॥ प्रत्ययस्य० ॥ ६१ ॥

(प्रदीपः) द्वितीयमिति । लोपविशेषणापेक्षया द्वितीयं, पाठापेक्षया तु तृतीयं भवति ॥ एकदेशलोप इति । अवयव-

क्रिया समुदायेऽपि व्यपदिश्यते—यथा पटो दग्ध इति । अवयवे हि पटाख्योऽवयवी समवेत इति तस्याप्यसौ दाहः । न त्वयं गौणो व्यपदेशः । गौणत्वे हि सति मुख्यस्यैव संप्रत्ययाच्च कर्तव्यमेव प्रत्ययग्रहणं स्यात् ॥ आघ्नीतेति । परत्वादुपधालोपे कृते पुनःप्रसङ्गविज्ञानादनुनासिकलोपः स्यात् ॥ ६१ ॥

(उद्द्योतः) न त्वयमिति । अयम्—अवयवदाहादौ समुदायदाहादिव्यपदेशो गौणो न, किंतु मुख्य एव; अवयवलोपे समुदायस्यापि लोपादित्यर्थः ॥ अनुनासिकेति । अनुदात्तोपदेशेत्यनेन ॥ आघ्नीत—इत्यत्र आङो यमहन इत्यात्मनेपदैकवचनम् ॥ संग्मीयेति । गमेर्विधिलिङि समो गम्यृच्छीत्यात्मनेपदे इटि शपो बहुलं छन्दसीति लुकि लिङः सलोपे इटोऽत्ति उपधालोपे रूपम् । तत्र प्रत्ययलक्षणेन झलादिक्ङित्परत्वादनुनासिकलोपः स्यात् । इदं च प्रयोजनं 'अप्राधान्येनाश्रयणे विध्यर्थं प्रत्ययलक्षणसूत्रम्' इति वार्तिकमते बोध्यम् ॥ ६१ ॥

—⁂—

(५७ प्रत्ययलक्षणातिदेशसूत्रम् ॥ १ । १ । ९ आ. ३)

प्रत्ययलोपे प्रत्ययलक्षणम् ॥ १।१।६२ ॥

(प्रथमप्रत्ययग्रहणप्रयोजनम्)

(आक्षेपभाष्यम्)

प्रत्ययग्रहणं किमर्थम् ?

(प्रदीपः) प्रत्यय० ॥ ६२ ॥ **प्रत्ययग्रहणमिति** । प्रत्ययनिमित्तं कार्यं लोपे भवतीत्युक्ते प्रत्यासत्त्या प्रत्ययस्यैव लोप इति विज्ञास्यत इति भावः ॥

(उद्द्योतः) प्रत्ययलोपे० ॥ ६२ ॥ लक्षणशब्दार्थमाह—निमित्तमिति ॥ कार्यमिति । बहुव्रीहिलभ्यम् ॥ प्रत्यासत्त्येति । क्रियमाणेऽपि प्रत्ययग्रहणेऽन्यप्रत्ययलोपेऽन्यप्रत्ययनिमित्तकार्यवारणाय प्रत्यासत्तिराश्रयणीयेति भावः ॥

(समाधानभाष्यम्)

"लोपे प्रत्ययलक्षणम्" इतीयत्युच्यमाने—सौरथी वैहतीति गुरूपोत्तमलक्षणः ष्यङ् प्रसज्येत ॥

(प्रदीपः) **सौरथीति** । प्रत्ययस्य लक्षणं=दर्शनं=प्रादुर्भाव इत्यर्थं परिकल्प्यैतदुच्यते । सुरथस्य विहतस्य चापत्यं गोत्रं स्त्रीति अत इञि कृते मकारनकारयोर्भावे यथा गुरूपोत्तमत्वात् ष्यङ् भवति, एवं लोपेऽपि स्यात् । प्रत्ययग्रहणे तु सति विरुद्धत्वान्नायमर्थो भवति—प्रत्ययलोपे तस्यैव पुनः प्रादुर्भाव इति ॥ एवं हि लोपविधानमनर्थकं स्यात् । तस्मात्—प्रत्ययनिमित्तं कार्यं प्रत्ययलोपे भवतीति वाक्यार्थ आश्रीयते ॥

(उद्द्योतः) ननु प्रत्ययलक्षणमित्यस्य बहुव्रीहितयाऽनेन स्थान्यभावेऽप्राप्तकार्यप्रापणायातिदेश इति अत्र प्रत्ययस्य सत्त्वेन किं तन्निमित्तकार्यातिदेशेनात आह—प्रत्ययस्य लक्षणमिति । यस्य लोपस्तस्मिन्सति यः प्रत्ययो भवति, तस्य तल्लोपेऽपि प्रादुर्भाव इत्यर्थः ॥ लाघवात्षष्ठीतत्पुरुष एव स्यादिति तात्पर्यम् ॥ रमेः क्वनि हन्तेश्च रेः अनुदात्तेत्यनुनासिकलोपेऽगुरूपोत्तमत्वादप्राप्तः ष्यङिति देशतः स्यादित्यर्थः ॥ एवं हि लोपेति । ननु णेरनिटीत्यादिसामर्थ्यात् मा भूत्तत्र प्रवृत्तिः । यस्तु सामान्येन लोपो णाविष्ठवदिति, सोऽप्रत्ययविषये चरितार्थ इति भिक्षुमाचष्टे भिक्षयतीत्यत्र पुनः प्रादुर्भावार्थमिदं स्यादिति चेन्न । एवं हि तत्रैव प्रत्ययस्य न लोप इति वदेत् । एवं च गुरुतरन्यासो ज्ञापक इति बोध्यम् ॥

(समाधाननिराकरणभाष्यम्)

नैष दोषः । नैवं विज्ञायते—लोपे प्रत्ययलक्षणं भवति=प्रत्ययस्य प्रादुर्भाव इति ॥

कथं तर्हि ?

प्रत्ययो लक्षणं यस्य कार्यस्य तल्लुप्तेऽपि भवति—इति ॥

(प्रदीपः) **नैवमिति** । संदेहेऽपि व्याख्यानात्करणसाधनो लक्षणशब्द आश्रयिष्यते । अन्यथा क्रियमाणेऽपि प्रत्ययग्रहणे भावसाधनाशङ्का न निवर्तेत—प्रत्ययलोपे प्रत्ययान्तरस्य प्रादुर्भाव इति । यथा—ग्रामणीरिति क्विलोपे स्वाद्युत्पत्तिः । ततश्चाधोगित्यत्र पदसंज्ञा न स्यादिति करणसाधनत्वे व्याख्यानमेव शरणमिति भावः । लक्षणशब्दोपादानसामर्थ्याद्वा करणसाधनो लक्षणशब्दः । अन्यथा **'लोपे प्रत्ययः'** इत्येवं वक्तव्यं स्यात् ॥

(उद्द्योतः) अन्यथा—व्याख्यानस्य शरणत्वाभावे ॥ पदसंज्ञा न स्यादिति । तिङन्तत्वाभावादिति भावः ॥ लोपे प्रत्यय इति । अस्य प्रादुर्भवतीति शेषः ॥

(प्रयोजनान्तरभाष्यम्)

इदं तर्हि प्रयोजनम्—सति प्रत्यये यत्प्राप्नोति तत्प्रत्ययलक्षणेन यथा स्यात्, लोपोत्तरकालं यत्प्राप्नोति तत्प्रत्ययलक्षणेन मा भूदिति ॥

किं प्रयोजनम् ?

ग्रामणिकुलं, सेनानिकुलम् । औत्तरपदिके ह्रस्वत्वे कृते "ह्रस्वस्य पिति कृति तुक्" इति तुक् प्राप्नोति, स मा भूदिति ॥

(प्रदीपः) **सति प्रत्यय इति** । प्रत्ययशब्दोऽत्र लुप्तसप्तमीको निर्दिश्यते । तेन प्रत्यये सति यत्कार्यं दृष्टं तल्लोपेऽपि भवति । न च ग्रामणीरित्यत्र क्विपि सति तुक् दृष्टः, ह्रस्वाभावात् । कृते क्विलोपे ह्रस्वत्वे च तुक्प्राप्तिः ॥

(उद्द्योतः) ननु 'प्रत्ययलोपे' इत्युक्ते कथं 'सति प्रत्यये' इति लभ्यतेऽत आह—प्रत्ययशब्द इति ॥ यत्कार्यमिति । प्रत्ययलक्षणं यत्कार्यं दृष्टमित्यर्थः ॥

(प्रयोजननिराकरणभाष्यम्)

यदि तर्हि—यत्सति प्रत्यये प्राप्नोति, तत्प्रत्ययलक्षणेन भवति । लोपोत्तरकालं यत् प्राप्नोति, तन्न भवति । जगत्—जनगत्—इत्यत्र तुक् न प्राप्नोति लोपोत्तरकालं ह्यत्र तुगागमः । तस्मान्नार्थ एवमर्थेन प्रत्ययग्रहणेन ॥

(प्रदीपः) **जगदिति** । द्युतिगमिजुहोत्यादीनां द्वे चेति गमेः क्विप् । अत्रान्तरङ्गत्वात्पूर्वं विलोपः । गमः

कावित्वं हि लोपोऽङ्गविशेषापेक्षत्वाद्बहिरङ्गः । भिन्नविषयत्वाच्च येन नाप्राप्त इति न्यायो न भवति । सति त्वस्मिन्न्याये नैव विलोपः स्यात् । तस्मात्सति क्विपि नाऽत्र तुकः प्राप्तिः, अपि तु विलोपे कृते ॥

(उद्योतः) ननु जगदित्यादौ विलोपात्परत्वात्पूर्वं गमःक्वावित्यनुनासिकलोपे क्विपि सत्यपि तुकः प्राप्तिराह—अत्रेति ॥ भिन्नविषयत्वादिति । वार्तिकमते एतत् । अचिरादेशे नुडपवादत्वंपरभाष्यरीत्या विषयभेदेऽपि तत्त्वे तु लोपेनानुत्पत्तेरेवान्वाख्यानेनापवादत्वं नेति बोध्यम् ॥ वैपरीत्याभ्युपगमेऽङ्गीकारे दोषमाह—सति त्विति ॥

(आक्षेपभाष्यम्)

कस्मान्न भवति—ग्रामणिकुलं, सेनानिकुलम् ?

(समाधानभाष्यम्)

बहिरङ्गं ह्रस्वत्वम्, अन्तरङ्गस्तुक् । "असिद्धं बहिरङ्गमन्तरङ्गे" ॥

(प्रयोजनान्तरभाष्यम्)

इदं तर्हि प्रयोजनम्—कृत्स्नप्रत्ययलोपे प्रत्ययलक्षणं यथा स्यात्, एकदेशलोपे मा भूदिति । 'आघ्रीत' 'सं रायस्पोषेण ग्मीय'—इति ॥

(आक्षेपभाष्यम्)

पूर्वस्मिन्नपि योगे प्रत्ययग्रहणस्यैतत्प्रयोजनमुक्तम् ॥

(समाधानभाष्यम्)

अन्यतरच्छक्यमकर्तुम् ॥

(प्रदीपः) अन्यतरदिति । एकमेव प्रत्ययग्रहणं सामर्थ्यात् कृत्स्नप्रत्ययलोपप्रतिपादने समर्थम् ॥

(उद्योतः) एकमेवेति । अवयवस्य प्रत्ययत्वपर्याप्त्यधिकरणत्वाभावादिति भावः । एवञ्चानयोः फलान्तराभिनिवेशो भाष्यविरुद्ध इति बोध्यम् ॥

(द्वितीयप्रत्ययग्रहणप्रयोजनम्)

(आक्षेपभाष्यम्)

अथ द्वितीयं प्रत्ययग्रहणं किमर्थम् ?

(समाधानभाष्यम्)

प्रत्ययलक्षणं यथा स्यात्, वर्णलक्षणं मा भूदिति । गवे हितं—गोहितम्, रायः कुलं—रैकुलमिति ॥

(प्रदीपः) वर्णलक्षणमिति । 'प्रत्ययलोपे तल्लक्षणं' इत्युच्यमाने प्रत्ययस्य यत्र कार्ये निमित्तभावः प्रत्ययस्वरूपाऽऽश्रयेण वर्णरूपताऽऽश्रयेण वा तत्सर्वं स्यात्, सर्वनाम्नो वस्तुमात्रपरामर्शित्वात् । प्रत्ययग्रहणे सति प्रत्ययनिमित्तमेव कार्यं प्रत्ययलोपे भवति, न वर्णरूपतानिमित्तम् ॥ रैकुलमिति । अवयवद्वारेणात्र प्रत्ययस्याप्यायादेशं प्रति निमित्तत्वमस्त्येव । प्रत्ययाश्रयस्त्वायादेशो न भवति—इति न प्रवर्तते । अनेनैव न्यायेन **न धातुलोप आर्धधातुके** इति धिन्विकृण्व्योर्वेन्वि **लोपो व्योर्वलीति** वलोपस्य वल्निमित्तत्वादार्धधातुकनिमित्तत्वाभावाद्गुणनिषेधो न भवति । तेन—'सुधे' 'सुकर्' इति, न तु सुधी सुधिनौ सुकीरिति ॥

(उद्योतः) ननु द्वितीयप्रत्ययग्रहणाभावे वस्तुत्रोऽप्यलाभाच्छब्दकार्यातिदेशो न सिध्येदत आह—तल्लक्षणमिति ॥ वस्तुमात्रेति । प्रत्ययमात्रेत्यर्थः ॥ प्रत्ययनिमित्तमेवेति । प्रत्ययत्वेन प्रत्ययनिमित्तमित्यर्थः ॥ न वर्णेति । प्राधान्येन वर्णनिमित्तमित्यर्थः ॥ ननु रैकुलमित्यत्रायादेशो न प्रत्ययाश्रयः, किंतु तदवयवाश्रयोऽत आह—अवयवद्वारेणेति ॥ केचित्तु प्रत्ययग्रहणमित्यस्य द्वितीयप्रत्ययपदघटितं प्रत्ययलक्षणग्रहणमित्यर्थः ॥ प्रत्ययलोपेऽपीत्येव सूत्रं कार्यम् । अस्य 'तद्भवति यत् प्रत्यये सति' इति शेषः । स्थानिवदित्यनुवृत्तिर्वा ॥ प्रत्ययलक्षणमिति । प्रत्ययत्व-तद्व्याप्यान्यतरधर्मावच्छिन्नलक्षणमित्यर्थः ॥ वर्णलक्षणं—वर्णत्वव्याप्यधर्मावच्छिन्ननिमित्तम् ॥ प्रत्यये सति वर्णनिमित्तं भवतीति तल्लोपेऽपि स्यादिति भावः ॥ कैयटव्याख्या तु चिन्त्या । प्रकृते तच्छब्दप्रत्ययशब्दयोः पर्यायत्वेन तद्विचारस्यायुक्तत्वापत्तेरित्याहुः ॥ अनेनैवेति । अत्र प्रत्ययग्रहणसामर्थ्यात्तथाऽर्थलाभेऽपि तत्र तादृशार्थग्रहे न मानम् ॥ आर्धधातुक इत्यस्य कैयटरीत्या सोतोर्त्यादिव्यावृत्त्या चरितार्थत्वात् ॥ पूर्वसूत्रे आर्धधातुकग्रहणमनवकाशमिति क्ङिति चेति सूत्रस्थभाष्यविरोधाच्च । आवृत्त्यादिना तथाऽर्थकल्पने तु न मानम् ॥ किंच तथाऽर्थकल्पने यण्व्यक्कयवलोपे इति वार्तिकं तदुदाहरणपरं जीरदानुरिति भाष्यं चासङ्गतं स्यादिति चिन्त्यमेतत् ॥ सुधे इत्यादि । धिविकृण्व्योर्नुमि विचि वलोपेऽपृक्तलोपे गुणे सुना समासे सौ हल्ङ्यादिलोपनलोपयोरिमे रूपे ॥ गुणनिषेधे तु सुधिन्शब्दे इन्हन्निति दीर्घः । सुकुणः सर्वनामस्थाने चेति दीर्घ उपधाया इतीत्त्वे रपरत्वे सुनलोपयोर्वोरिति दीर्घः स्यादिति भावः ॥

(सूत्रप्रणयने युक्तिप्रदर्शनम्)

(आक्षेपभाष्यम्)

किमर्थं पुनरिदमुच्यते ?

(प्रदीपः) किमर्थमिति । स्थानिवद्भावेन सिद्धमिति भावः ॥

(उद्योतः) स्थानिवद्भावेनेति । वर्णाश्रयस्य तत्राप्यनिष्टत्वादित्यर्थः ॥

(३७९ समाधानवार्तिकम् ॥ १ ॥)

॥ * ॥ प्रत्ययलोपे प्रत्ययलक्षणवचनं सदन्वाख्यानाच्छास्त्रस्य ॥ * ॥

(भाष्यम्)

"प्रत्ययलोपे प्रत्ययलक्षणम्" इत्युच्यते 'सदन्वाख्यानाच्छास्त्रस्य' । सत् शास्त्रेणान्वाख्यायते, सतो वा शास्त्रमन्वाख्यायकं भवति । सदन्वाख्या-

नाच्छास्त्रस्य "उगिदचां सर्वनामस्थानेऽधातोः" इतीहैव स्यात्—गोमन्तौ, यवमन्तौ । गोमान्, यवमानित्यत्र न स्यात् । इष्यते च स्यादिति । तच्चान्तरेण यत्नं न सिध्यति । अतः प्रत्ययलोपे प्रत्ययलक्षणवचनम् । एवमर्थमिदमुच्यते ॥

(प्रदीपः) **सदन्वाख्यानादिति** । शास्त्रं कर्तृ करणं वा शेषत्वेन विवक्षितमिति षष्ठी कृता ॥ **सत् शास्त्रेणेति** । शास्त्रेण करणेनाचार्यः-स्मर्ता सत्-विद्यमानं वस्तु निमित्तत्वेनान्वाचष्टे ॥ **सतो वेति** । शास्त्रस्यैवाविच्छेदेन प्रवर्तमानस्य स्वतन्त्रत्वमन्वाख्याने-इति पूर्वस्माद्व्याख्यानादस्य विशेषः ॥ न च स्थानिवद्भावेन सिध्यति । अतृणेडित्यादावल्विधित्वात् ॥

(उद्द्योतः) ननु शास्त्रस्य कर्तृत्वे सतः कर्मत्वेनोभयप्राप्ताविति नियमाच्छास्त्रस्य-इति षष्ठ्यनुपपन्ना, कर्मणि चेति समासनिषेधापत्तिश्च । करणत्वे तु षष्ठ्यनुपपन्नेत्यत आह—**शास्त्रमिति** । शेषत्वे चोभयप्राप्तावित्यस्याप्राप्तेः षष्ठीसमासौ नानुपपन्नौ-इति भावः ॥ **आचार्यः स्मर्ता** इति फलितार्थकथनम् ॥ **सत्राचार्येणेति** तु 'अन्वाख्यायते' इत्यन्वययोग्यम् ॥ **स्वतन्त्रत्वमिति** । करणस्य कर्तृत्वविवक्षेति भावः ॥ **अल्विधित्वादिति** । इमादेरिति शेषः । **वर्णाश्रयेति** तु वर्णप्राधान्यविषयकम् । एवं चाप्राधान्येनाल्लाश्रयणे विध्यर्थं सूत्रमिति भावः ॥

(आक्षेपभाष्यम्)

अस्ति प्रयोजनमेतत् ॥

(उद्द्योतः) भाष्ये—**अस्तिप्रयोजनमेतदिति** । उक्तप्रयोजनविशिष्टं सूत्रं निर्दोषं वा-इति काका प्रश्न इति बोध्यम् ॥

(समाधानभाष्यम्)

किं तर्हीति ?

(उद्द्योतः) **किं तर्हीति** । मम तु निर्दोषमेव, तव कश्चिद्दोषप्रतिभासोऽस्ति चेद्वद-इति प्रश्नगर्भमुत्तरम् ॥

———

(लुकि प्रत्ययलक्षणसाधनम्)

(३८० आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ लुक्युपसंख्यानम् ॥ * ॥

(भाष्यम्)

लुकि उपसंख्यानं कर्तव्यम् । पञ्च, सप्त ॥

(प्रत्याक्षेपभाष्यम्)

किं पुनः कारणं न सिध्यति ?

(३८१ आक्षेपसाधकवार्तिकम् ॥ २ ॥)

॥ * ॥ लोपे हि विधानम् ॥ * ॥

(भाष्यम्)

लोपे हि प्रत्ययलक्षणं विधीयते । तेन लुकि न प्राप्नोति ॥

(प्रदीपः) **लुक्युपसंख्यानमिति** । तक्रकौण्डिन्यन्यायेन लोपसंज्ञाया लुगादिसंज्ञाभिर्बाधनादिति भावः ॥ लुग्ग्रहणस्योपलक्षणार्थत्वात् श्लुलुपावपि गृह्येते ॥

(उद्द्योतः) बाधनादिति । एवं च 'पञ्च' इत्यादौ पदत्वं न स्यादिति भावः ॥ उपलक्षणार्थत्वादिति । तयोरपि पूर्वपक्षबीजस्य समत्वादिति भावः ॥ तत्र श्लुलुपोः प्रत्ययलक्षणस्य फलं चिन्त्यम्, लुकि तु पञ्चेत्यादौ पदत्वं फलमस्ति ॥

(३८२ समाधानवार्तिकम् ॥ ३ ॥)

॥ * ॥ न वाऽदर्शनस्य लोपसंज्ञित्वात् ॥ * ॥

(भाष्यम्)

न वा कर्तव्यम् ॥

किं कारणम् ?

'अदर्शनस्य लोपसंज्ञित्वात्' । अदर्शनं लोपसंज्ञं भवतीत्युच्यते । लुमत्संज्ञाश्चाप्यदर्शनस्य क्रियन्ते । तेन लुक्यपि भविष्यति ॥

(प्रदीपः) **न वाऽदर्शनस्येति** । अदर्शनमात्रस्य लोपसंज्ञा विधीयमाना लुगादिसंज्ञाविषयमप्यवगाहते । न च संज्ञानां बाध्यबाधकभावः, समावेशदर्शनात्तासामिति **आकडारसूत्रे** वक्ष्यते । लोपस्य संज्ञि—लोपसंज्ञि, तस्य भावो लोपसंज्ञित्वं, तस्मादित्यर्थः ॥

(उद्द्योतः) **समावेशदर्शनादिति** । कृत्कृत्यादिष्विति भावः ॥ लोपः संज्ञा यस्येति बहुव्रीहौ मत्वर्थीयानुपपत्तिः, इन्नन्तेन षष्ठीसमासेऽर्थासङ्गतिः, अत इन्नन्तेन षष्ठीसमास इत्याह-लोपस्येति ॥

———

(सांकर्यपरिहारः)

(संगतिभाष्यम्)

यद्येवम्—

(३८३ सांकर्याक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ प्रत्ययादर्शनं तु लुमत्संज्ञम् ॥ * ॥

(भाष्यम्)

प्रत्ययादर्शनं तु लुमत्संज्ञमपि प्राप्नोति ॥

(प्रदीपः) **प्रत्ययादर्शनं त्विति** । लुक्श्लुलुप्संज्ञानां संकरः प्राप्नोतीत्यर्थः ॥

(उद्द्योतः) **सङ्कर इति** । परस्परं, लोपशब्दभावितप्रत्ययादर्शनविषये लोपसंज्ञया चेत्यर्थः ॥ प्रत्ययादर्शनमात्रं सकललुमत्संज्ञं प्राप्नोतीति भाष्याक्षरार्थः ॥

(आक्षेपभाष्यम्)

तत्र को दोषः ?

(३८४ दोषदर्शनवार्तिकम् ॥ २ ॥)

॥ * ॥ तत्र लुकि श्लुविधिप्रतिषेधः ॥ * ॥

(भाष्यम्)

तत्र लुकि श्लुविधिरपि प्राप्नोति, स प्रतिषेध्यः । अस्ति-हन्ति "श्लौ" इति द्विर्वचनं प्राप्नोति ॥

(प्रदीपः) **तत्र लुकि श्लुविधिरिति** । उपलक्षणं चैतत् । तेन श्लावपि लुग्विधिः प्राप्नोति—जुहोतीति, उतो

वृद्धिर्लुकि हलीति ॥ लुप्यपि लुग्विधिप्रसङ्गः—हरीतकीति । तथा लुकि लुप्विधिः—लवणः सूप इति, युक्तवद्भावः स्यात् ॥

(उद्द्योतः) उतो वृद्धिरिति । न च तत्र नाभ्यस्तस्येति वर्तनाददोषः, अत्र पक्षे तदनुवृत्तेर्वक्तुमशक्यत्वात् ॥ हरीतकीति । नन्वत्र सत्यपि ङीपो लुकि युक्तवद्भावात् पुनर्ङीप् स्यादिति चेन्न । लक्ष्ये लक्षणस्येति न्यायादित्याहुः ॥ हरीतक्यां हरीतक्यादिभ्यश्चेत्यणो लुप् । यद्वा हरितकीवेयं प्रतिकृतिरिति कनो लुप् ॥ लवण इति । अत्र लवणाल्लुक् ॥

(३८५ सांकर्यवारणवार्तिकम् ॥ ३ ॥)

॥ * ॥ न वा पृथक्संज्ञाकरणात् ॥ * ॥

(भाष्यम्)

न वा एष दोषः ॥

किं कारणम् ?

'पृथक्संज्ञाकरणात्' । पृथक्संज्ञाकरणसामर्थ्याल्लुकि श्लुविधिर्न भविष्यति ॥

(प्रदीपः) **न वा पृथगिति** । एकयैव संज्ञया प्रदेशवाक्येषु संज्ञिप्रत्यायने सिद्धेऽनेकसंज्ञाविधानसामर्थ्यात्तद्भावितग्रहणं विज्ञायते । तत्राश्रितस्वरूपव्यापारा वा लुगादय आश्रीयन्ते, आवृत्तिर्वा लुगादिशब्दानामाश्रीयत इति तद्भावितग्रहणं सिध्यति ॥ विधिप्रदेशेषु चेतरेतराश्रयदोषानवतारः, नित्यशब्दाश्रयणाद्भाविसंज्ञाविज्ञानाद्वा ॥

(उद्द्योतः) तद्भावितग्रहणे युक्तिमाह—तत्राश्रितेति । आश्रितः स्वरूपस्य व्यापारोऽदर्शनविषयो यैस्ते, तथोक्ता इत्यर्थः ॥ 'अदर्शनबोधका लुगादिशब्दाः प्रत्ययादर्शनस्य संज्ञाः' इत्युक्ते प्रत्यासत्त्या यया संज्ञया यददर्शनं भाव्यते तस्यैव सा संज्ञा - इति लभ्यत इति भावः ॥ प्रत्यासत्तिः सर्वैर्दुर्ज्ञेयेत्यत आह—आवृत्तिर्वेति । तेन लुगादिशब्दभावितमदर्शनं क्रमेण तत्तत्संज्ञमित्यर्थः ॥ अदर्शनस्य नित्यत्वेऽपि तद्भावितत्वस्य शास्त्रायत्तत्वादितरेतराश्रयत्वं तदवस्थमेवेत्यत आह—भाविसंज्ञेति ॥

(लोपसंज्ञाया व्यापकत्वोपसंहारभाष्यम्)

तस्माददर्शनसामान्याल्लोपसंज्ञा लुमत्संज्ञा अवगाहते ॥

(सांकर्यसाधकभाष्यम्)

यथैव तर्हि–अदर्शनसामान्याल्लोपसंज्ञा लुमत्संज्ञा अवगाहते, एवं लुमत्संज्ञा अपि लोपसंज्ञामवगाहेरन् ॥

तत्र को दोषः ?

अगोमती गोमती सम्पन्ना—गोमतीभूता "लुक् तद्धितलुकि" इति ङीपो लुक् प्रसज्येत ॥

(प्रदीपः) **यथैवेति** । तिसृणां संज्ञानां विधानसामर्थ्यात्परस्परविषयावगाहनं तासां मा भूत्, लोपसंज्ञाविषये तु ताः प्रवर्तेरन् ॥ **गोमतीभूतेति** । च्वेर्लोपे कृते लुक्संज्ञायां सत्यां **लुक् तद्धितलुकीति** लुक् प्राप्नोति । पुंवद्भावस्त्वत्र न भवति, वैयधिकरण्यात् । महद्भूता ब्राह्मणीत्यत्र तु भवति, सामानाधिकरण्यात् । नित्यत्वाद्धि शब्दानां क्वचिद्विकारस्य जनिकर्तृत्वं, क्वचित्प्रकृतेः ॥

(उद्द्योतः) तद्भावितग्रहणपक्षे यथैवेत्यादिग्रन्थोऽनुपपन्न इत्यत आह—तिसृणामिति । इतरेतराश्रयपरिहाराय भाविसंज्ञाविज्ञानगौरवापत्त्या सामर्थ्यात्तिसृणामसङ्करः प्रतिपादितः, न तु तद्भावितपक्षाश्रयेणेत्यभिमानः ॥ **वैयधिकरण्यादिति** । भवनक्रियायां प्रकृतेः कर्तृत्वादिति भावः ॥ **क्वचिद्विकारस्येति** । वैरुतो वृत्तौ तद्वाक्ये च सर्वत्र प्रकृतेरेव कर्तृत्वम् । विकृतिशब्दस्यापि गौण्या प्रकृतिप्रवृत्तित्वात्सामानाधिकरण्यम् । अत एव गौणत्वान्महच्छब्दे आत्वाभावः । गोमतीशब्दे तु गोमतीनदीभिन्ना गोमतीनदीभूतेत्यर्थेनाभाषितपुंस्कत्वात् पुंवत्त्वाभाव इति बोध्यम् ॥

(सांकर्यबाधकभाष्यम्)

ननु चात्रापि *न वा पृथक्संज्ञाकरणात्* इत्येव सिद्धम् ॥

(प्रदीपः) **ननु चात्रापीति** । लुगादिसंज्ञानां भेदेनोपादानात्तद्भावितग्रहणमित्यर्थः ॥

(आक्षेपभाष्यम्)

यथैव तर्हि—पृथक्संज्ञाकरणसामर्थ्यात् लुमत्संज्ञा लोपसंज्ञां नावगाहन्ते, एवं लोपसंज्ञाऽपि लुमत्संज्ञा नावगाहेत । तत्र स एव दोषः—*लुग्युपसंख्यानम्* इति ॥

(उद्द्योतः) भाष्ये—**एवं लोपेति** । लोपसंज्ञायामपि तद्भावितग्रहणं मन्वानस्य चोद्यमेतत् ॥

(समाधानभाष्यम्)

अस्त्यन्यल्लोपसंज्ञायाः पृथक्संज्ञाकरणे प्रयोजनम् ॥

किम् ?

लुमत्संज्ञासु यदुच्यते तल्लोपमात्रे मा भूदिति ॥

(प्रदीपः) **अस्त्यन्यदिति** । प्रत्ययाप्रत्ययादर्शनस्य लोपसंज्ञा यथा स्यादिति ॥ **लोपमात्रे मा भूदिति** । यथा गोमतीभूतेति च्वेर्लोपे कृते **लुक् तद्धितलुकीति** न भवति । तस्माल्लोपसंज्ञायां नास्ति तद्भावितग्रहणम् ॥

(उद्द्योतः) अत्र सामर्थ्यात्तद्भावितग्रहणेऽपि लोपसंज्ञायां तद्ग्रहणे मानाभावः । न च लुगादिभ्यो लोपसंज्ञायाः पृथक्करणं मानम्, तस्याः प्रयोजनान्तरसत्त्वादित्याह—अस्त्यन्यदिति ॥ तद्दर्शयति—तल्लोपमात्र इति-भाष्ये ॥ स्वयं प्रयोजनान्तरमप्याह—प्रत्ययाप्रत्ययेति ॥

(समाधानान्तरभाष्यवार्तिकम्)

॥ लुमति प्रतिषेधाद्वा ॥

(भाष्यम्)

अथवा यदयं—"न लुमताङ्गस्य" इति प्रत्ययलक्षणप्रतिषेधं शास्ति, तज्ज्ञापयत्याचार्यः—भवति लुकि प्रत्ययलक्षणमिति ॥

(उद्द्योतः) भाष्ये—लुमतिप्रतिषेधाद्वेति । भवतु लोपसंज्ञायामपि तद्भावितग्रहणं, न लुमतेति निषेधेन तत्र लोपत्वनिमित्तकार्यप्रवृत्तिर्वार्यत इत्यदोष इति भावः ॥

(इष्टानुपपत्तिपरिहारः)

(१८६ आक्षेपवार्तिकम् ॥१॥)

॥*॥ सतो निमित्ताभावात्पदसंज्ञाऽभावः ॥*॥

(भाष्यम्)

सन् प्रत्ययो येषां कार्याणां न निमित्तं 'राज्ञः पुरुषः' इति, स लुप्तोऽप्यनिमित्तं स्यात्—राजपुरुष इति ॥

(प्रदीपः) **सतो निमित्ताभावादिति ।** निमित्तशब्देन निमित्तत्वमुच्यते । तेन यस्य सतः कार्यं प्रति निमित्तत्वं नाभूत्, स लुप्तोऽप्यनिमित्तं स्यादित्यर्थः ॥ **राज्ञ इति ।** सति ङसि भसंज्ञायां स्वादिष्विति पदसंज्ञा बाधितेति नलोपो नाभूत्, अल्लोपश्चाभूदिति लुप्तेऽपि तस्मिन्नलोपो न स्यात्, अल्लोपश्च स्यात् ॥

(उद्द्योतः) लुक्युपसङ्ख्यानमिति दोषे परिहृते, दोषान्तरमाशङ्कते—सतो निमित्तेति । वार्तिकतद्व्याख्यानयोर्विरोधं परिहरति—निमित्तशब्देनेति ॥

(समाधानभाष्यम्)

अस्तु तस्या अनिमित्तम्—या स्वादौ पदमिति पदसंज्ञा । या तु 'सुबन्तं पदम्' इति पदसंज्ञा सा भविष्यति ॥

(प्रदीपः) **अस्तु तस्या इति ।** द्वे चात्र पदसंज्ञे । एका स्वादिष्विति अवयवस्य, सा च भसंज्ञया बाधिता । द्वितीया सुबन्तत्वेन समुदायस्य, सा च लुप्तेऽपि स्थितैव । अल्लोपस्तु न लुमताङ्गस्येति प्रतिषेधान्न भवति ॥

(उद्द्योतः) नन्वेवं पदत्वेऽपि भत्वस्यापि सत्त्वादल्लोपः स्यादत आह—अल्लोपस्त्विति ॥

(आक्षेपसाधकभाष्यम्)

सत्येतत् प्रत्यय आसीत्—अनया भविष्यत्यनया न भविष्यतीति । लुप्त इदानीं प्रत्यये यावत एवावधेः स्वादौ पदमिति पदसंज्ञा तावत एव सुबन्तं पदमिति । अस्ति च प्रत्ययलक्षणेन यजादिपरतेति कृत्वा भसंज्ञा प्राप्नोति ॥

(प्रदीपः) **सत्येतदिति ।** कालविप्रकर्षप्रतिपादनायानद्यतनप्रत्ययप्रयोगः । राज्ञ इत्यत्रावधिभेदाद्भसंज्ञयाऽवयवस्यैव पदसंज्ञा बाध्यते, न समुदायस्य सुबन्तत्वनिमित्ता । लुप्ते तु प्रत्ययेऽवधिभेदाभावात्प्रत्ययलक्षणेन प्राप्तया भसंज्ञया द्वे अपि पदसंज्ञे बाधितव्ये । एकाऽपवादत्वेन, द्वितीया परत्वेनेति भावः ॥ **अनयेति ।** पदसंज्ञाद्वयमनेन दर्शितम् । भसंज्ञा प्रत्ययलक्षणेन वर्णाश्रयाऽपि भवति । यथा—अतृणेडितीमागमः ॥

(उद्द्योतः) कालविप्रकर्षेति । अस्य चोत्तरस्य नायमवसर इत्यर्थः ॥ भाष्ये—एतत्—वक्ष्यमाणवाक्यार्थरूपम् ॥ पदसंज्ञाद्वयमिति । अनया पदसंज्ञया नलोपो भविष्यतीत्यादिर्भाष्यार्थः ॥ यथेति । वर्णप्राधान्यविषय एव स निषेध इति भावः ॥

(१८७ आक्षेपान्तरवार्तिकम् ॥ २ ॥)

॥ * ॥ तुग्दीर्घत्वयोश्च विप्रतिषेधानुपपत्तिरेकयोगलक्षणत्वात् परिवीरिति ॥ * ॥

(भाष्यम्)

तुग्दीर्घत्वयोश्च विप्रतिषेधो नोपपद्यते ॥

क ?

परिवीरिति ॥

किं कारणम् ?

'एकयोगलक्षणत्वात्' । एकयोगलक्षणे हि तुग्दीर्घत्वे ॥ इह लुप्ते प्रत्यये सर्वाणि प्रत्ययाश्रयाणि कार्याणि पर्यवपन्नानि । तान्येतेन प्रत्युत्थाप्यन्ते । अनेनैव तुक् अनेनैव च दीर्घत्वमिति, तदेकयोगलक्षणं भवति । एकयोगलक्षणानि च न प्रकल्पन्ते ॥

(प्रदीपः) **तुग्दीर्घत्वयोश्चेति ।** अनेनैव प्रत्ययनिमित्तानि कार्याणि लुप्तेऽपि प्रत्यये विधीयन्ते-इति क्रमाभावात्पौर्वापर्यं न प्रकल्प्यते । कार्यस्य प्राधान्यात्तानेन शास्त्रव्यपदेशौ विधीयेते ॥

(उद्द्योतः) भाष्ये—पर्यवपन्नानि—मृतानि । अप्राप्तानीति यावत् ॥ नन्वेतत् कार्यातिदेशे स्यात्, स एव कुतः ? शास्त्रनिमित्तातिदेशयोरपि संभवात् । अत आह—कार्यस्येति । व्यपदेशः-निमित्तम् ॥ विधीयेते इति । 'इत्यभिमानः' इति शेषः ॥ वस्तुतः कार्यशास्त्रातिदेशयोरभेद एवेत्युक्तम् ॥ भाष्ये—एकयोगलक्षणानि चेति । तादृशानि विप्रतिषेधविषयत्वेन न कल्प्यन्त इत्यर्थः ॥

(१८८ न्यासान्तरेण समाधानवार्तिकम् ॥ ३ ॥)

॥ * ॥ सिद्धं तु स्थानिसंज्ञानुदेशादान्यभाव्यस्य ॥ * ॥

(भाष्यम्)

सिद्धमेतत् ॥

कथम् ?

स्थानिसंज्ञाऽन्यभूतस्य भवतीति वक्तव्यम् ॥

किं कृतं भवति ?

सत्तामात्रमनेन क्रियते । यथाप्राप्ते तुग्दीर्घत्वे भविष्यतः ॥

(प्रदीपः) **सिद्धं त्विति ।** अन्यो भावः-अन्यद्वस्तु स्थान्यपेक्षयाऽऽदेशः, अन्यभाव एवान्यभाव्यमिति स्वार्थे ष्यञ् । तत्र परिवीरिति स्थानिनः क्विपो या संज्ञा=यो व्यपदेशः-पित् कृत्प्रत्यय इत्यादिः, स लोपस्यानेन विधीयते । ततस्तन्निबन्धनं शास्त्रं प्रवर्तेत इति सिद्धो विप्रतिषेधः ॥ **सत्तामात्रमिति ।** कृदादिव्यपदेशस्येत्यर्थः ॥

(उद्योतः) अन्यान्यभाव इति षष्ठीतत्पुरुषः कर्मधारयो वा उभयथापि च्यमनुपपन्नः। भावस्य भावान्तरेणायोगात्, समासस्य च गुणवचनसंज्ञाया बाधात्, अर्थासङ्गतेश्च, इत्यत आह—अन्यो भाव इति। भाष्येऽन्यरूपं भावस्येत्यर्थकमन्यभूतस्येत्येतत्तु फलितार्थो बोध्यः॥ स्वार्थे इति। चातुर्वर्ण्यादित्वात्॥ ननु सत्ता सैवाति-नभेदित्युक्तम्, अतिदेशसहस्रेण सत्ताया अशक्यत्वात्, अत आह—रूपाभिव्यपदेशस्येति। एतदर्थमेव स्थानिसंज्ञानुदेशादित्युक्तम्, न तु 'स्थान्यनुदेशात्' इति। तथा सति स्थानिकार्यातिदेश एव स्यादिति बोध्यम्॥

(आक्षेपभाष्यम्)

तद्वक्तव्यं भवति॥

(उद्योतः) भाष्ये शङ्किता आह—तद्वक्तव्यमिति। वचनान्तरेण तत्राक्षेपपरिहारो न युक्त इति भावः॥

(न्यासान्तरसाधकसमाधानभाष्यम्)

यद्यप्येतदुच्यते, अथवैतर्हि स्थानिवद्भावो नारभ्यते। "स्थानिसंज्ञाऽन्यभूतस्यानल्विधौ" इति वक्ष्यामि॥

(उद्योतः) परिहरति—यद्यपीति॥ अथवैतर्हीति। तथापीत्यर्थः। एवं च लघुतरत्वाद्वचनान्तरेणापि परिहारो युक्त इति भावः॥

(आक्षेपभाष्यम्)

यद्येवम् "आङो यमहनः" आत्मनेपदं भवतीति हन्तेरेव स्यात्, वधेर्न स्यात्। न हि काचिद्धन्तेः संज्ञाऽस्ति, या वधेरतिदिश्येत॥

(प्रदीपः) यद्येवमिति। हन्तिं स्वरूपेणोपादायात्मनेपदं विधीयते। न तु कांचित्संज्ञामाश्रित्येति भावः॥ न हीति। यद्यपि धातुसंज्ञाऽस्ति, तथापि न तदुपादानेनात्मनेपदं विधीयते॥

(उद्योतः) संज्ञामिति। निमित्तभूतव्यपदेशमित्यर्थः॥

(समाधानभाष्यम्)

हन्तेरपि संज्ञाऽस्ति॥

का?

हन्तिरेव॥

कथम्?

"स्वं रूपं शब्दस्याशब्दसंज्ञा" इति वचनात्स्वं रूपं शब्दस्य संज्ञा भवतीति हन्तेरपि हन्तिः संज्ञा भविष्यति॥

(प्रदीपः) हन्तेरपीति। आङो यमहन इति सूत्रोपात्तो हन्तिः संज्ञा, प्रयोगस्थस्तु संज्ञीति वधेर्हन्तिसंज्ञाऽतिदेक्ष्यते॥

(उद्योतः) ननु संज्ञासंज्ञिनोर्भेदाभावाद्धन्तिः संज्ञेत्ययुक्तमत आह—सूत्रोपात्त इति॥

(१८९ न्यासान्तरप्रयोजनान्तरवार्तिकम्॥ ४॥)

॥ * ॥ भसंज्ञाङीप्ष्फगोरात्वेषु च सिद्धम्॥ * ॥

(भाष्यम्)

भसंज्ञाङीप्ष्फगोरात्वेषु च सिद्धं भवति॥

(उद्योतः) फलान्तरमपि वचनान्तरारम्भे दर्शयति भाष्ये—भेत्यादि॥ सिद्धमिति। इष्टमिति शेषः। वक्ष्यमाणान्यल्विधित्वाद्वार्तिकमते नातिदेशेन भविष्यन्ति॥ सूत्रारम्भे तु वर्णाश्रये इत्यस्य वर्णप्राधान्यविषयत्वादतिदेशेन स्युरेवेति भावः॥

(उदाहरणोपपादनभाष्यम्)

भसंज्ञा—राज्ञः पुरुषः-राजपुरुषः। प्रत्ययलक्षणेन "यचि भम्" इति भसंज्ञा प्राप्नोति, "स्थानिसंज्ञाऽन्यभूतस्यानल्विधौ" इति वचनान्न भवति॥

(उदाहरणोपपादनभाष्यम्)

ङीप्—चित्रायां जाता-चित्रा। प्रत्ययलक्षणेनाणन्तादिति ईकारः प्राप्नोति। "स्थानिसंज्ञाऽन्यभूतस्यानल्विधौ" इति वचनान्न भवति॥

(प्रदीपः) चित्रायां जातेति। चित्रारेवतीरोहिणीभ्यः स्त्रियामुपसंख्यानमित्यणो लुक्॥ टिड्ढाणञित्यत्रात इत्यधिकारात् ङीपोऽल्विधित्वम्॥

(उद्योतः) चित्रेति। नक्षत्रेण युक्त इत्यणो लुबविशेष इति लुप्। युक्तवद्भावात्स्त्रीत्वं, ततो जातेऽर्थे सन्धिवेलादीत्यणो वार्तिकेन लुक् इति भावः। न चाणो लुकि लुक्तद्धितेति टापो लुकि पुनष्टाप् दुर्लभः, लक्ष्ये लक्षणस्येति न्यायात्—इति वाच्यम्। जातगतस्त्रीत्वबोधनरूपफलस्यासिद्धतया प्रवृत्तेः॥ अत इत्यपीति। अकारान्तादण इत्यर्थः॥

(उदाहरणोपपादनभाष्यम्)

ष्फ—वातण्डी। प्रत्ययलक्षणेन 'यञन्तात्' इति ष्फः प्राप्नोति। "स्थानिसंज्ञाऽन्यभूतस्यानल्विधौ" इति वचनान्न भवति॥

(प्रदीपः) वातण्डीति। यथा-आवट्यायनीति चापं बाधित्वा सर्वत्रग्रहणापकर्षात् ष्फो भवति, एवं शार्ङ्गरवादिपाठात् प्राप्तं ङीनं बाधित्वा प्राचां ष्फः स्यात्॥ अत इत्यधिकारादल्विधिः ष्फः॥

(उद्योतः) ननु वतण्डात् स्त्र्यपत्ये यञो लुक् स्त्रियामिति लुकि प्रत्ययलक्षणेन प्राचामिति प्राप्तष्फं बाधित्वा परत्वात् ङीन् स्यात्, शार्ङ्गरवादिपाठादत आह—यथेति। तेन हि सूत्रे यञ इति वर्तते॥ सर्वत्रग्रहणेति। तद्धि पूर्वसूत्रेऽपकृष्यते॥

(उदाहरणोपपादनभाष्यम्)

गोरात्वम्—गामिच्छति—गव्यति। प्रत्ययलक्षणेनामि "औतोऽम्शसोः" इत्यात्वं प्राप्नोति। "स्थानिसंज्ञाऽन्यभूतस्यानल्विधौ" इति वचनान्न भवति॥

(प्रदीपः) गव्यतीति। औतोऽम्शसोरित्यत्राचीत्यनुवर्तनादल्विधिरात्वम्॥

(उद्योतः) औतोमिति। एकादेशविधायकं हि तत्॥ अचीति। अजाद्योरित्यर्थः। अत एव तद्धितशसो निवृत्तिः॥

(३९० न्यासान्तरदूषणवार्तिकम् ॥ ५ ॥)

॥*॥ तस्य दोषो ङौनकारलोपेत्त्वे-ड्विधयः ॥*॥

(भाष्यम्)

तस्यैतस्य लक्षणस्य दोषः ॥

(उद्द्योतः) भाष्ये सूत्रारम्भवादी वचनान्तरवादिनं प्रति दूषणमाह—तस्य दोष इति । 'स्थानिसंज्ञानुदेशात्' इत्यस्येत्यर्थः ॥

(उदाहरणोपपादनभाष्यम्)

ङौ नकारलोपः—आर्द्रे चर्मन्, लोहिते चर्मन् । प्रत्ययलक्षणेन "यचि भम्" इति भसंज्ञा सिद्धा भवति । 'स्थानिसंज्ञाऽन्यभूतस्यानल्विधौ' इति वचनान्न प्राप्नोति ॥

(प्रदीपः) चर्मन्निति । सुपां सुलुगिति ङेर्लुक् । अत्र भसंज्ञाया अभावान्नलोपः प्राप्नोतीति न ङिसंबुद्ध्योरिति वक्तव्यं जायते ॥

(उदाहरणोपपादनभाष्यम्)

इत्त्वम्—आशीः । प्रत्ययलक्षणेन 'हलि' इतीत्त्वं सिद्धं भवति । 'स्थानिसंज्ञाऽन्यभूतस्यानल्विधौ' इति वचनान्न प्राप्नोति ॥

(उद्द्योतः) इत्त्वम्–शास इदङ्हलोरिति ॥

(उदाहरणोपपादनभाष्यम्)

इम्—अतृणेट् । प्रत्ययलक्षणेन 'हलि' इति इम् सिद्धो भवति । 'स्थानिसंज्ञाऽन्यभूतस्यानल्विधौ' इति वचनान्न प्राप्नोति ॥

(उद्द्योतः) इम्–तृणह इत्यनेन ॥

(तटस्थभाष्यम्)

सूत्रं च भिद्यते ॥

(सिद्धान्तिभाष्यम्)

यथान्यासमेवास्तु ॥

(आक्षेपस्मारणभाष्यम्)

ननु चोक्तम्—*सतो निमित्ताभावात्पदसंज्ञाऽभावः * तुग्दीर्घत्वयोश्च विप्रतिषेधानुपपत्तिरेकयोगलक्षणत्वात्परिवीः * इति ॥

(प्रथमदूषणपरिहारभाष्यम्)

नैष दोषः । वक्ष्यत्यत्र परिहारम् ॥

(उद्द्योतः) भाष्ये—वक्ष्यत्यत्रेति । नह्रीति ङौ नलोपप्रतिषेधाज्ज्ञापकात्प्रत्ययलक्षणेन भसंज्ञा नेत्येवं रूपमनुपदमेतत्सूत्र एव–इत्यर्थः ॥

(द्वितीयदूषणपरिहारभाष्यम्)

इहापि परिवीरिति । शास्त्रपरविप्रतिषेधेन परत्वाद्दीर्घत्वं भविष्यति ॥

(प्रदीपः) परत्वाद्दीर्घत्वमिति । सति प्रत्यये यत्कार्यं दृष्टं तल्लुप्तेऽपि भवतीति सूत्रार्थः । परिवीयेत्यादौ च सति प्रत्यये दीर्घो दृष्टः, न तुगिति परिवीरित्यत्रापि दीर्घ एव भवति ॥

(उद्द्योतः) (भाष्ये) शास्त्रपरेति । उपदेशशास्त्रपरेत्यर्थः अतादृश्यमानकार्याणामुत्पत्तिदेश एव विप्रतिषेधशास्त्रोपयोगाति भावः । तदाह—सति प्रत्यये इति । इदं सूत्रं तत्तच्छास्त्रनिमित्तसंपादनद्वारा तत्तच्छास्त्रप्रवृत्तिसंपादकमिति भावः ॥ अत एव पूर्वं तान्यनेन प्रत्युत्थाप्यन्त इत्युक्तम् । तानि–तत्कार्यबोधकानि शास्त्राणि–इति तदर्थ उचितः, न तु 'कार्याणि क्रियन्ते' इत्यर्थः । [क्रियन्ते इत्यस्यैव वक्तुमुचितत्वात् ।] अत एव टित आत्मनेपदानामिति सूत्रे पर्यवपादौ–रूपान्तरापत्तिरित्युक्तं कैयटेन । विद्यमानस्य हि रूपान्तरापत्तिर्भवति । शास्त्रमेव च विद्यमानं न तु कार्यम् । तस्य च रूपान्तरं–एतद्विषयं कार्यप्रवर्तकत्वम् । एवं च पर्यवपन्नत्वमपि शास्त्रस्यैवेत्यन्ये ॥

(सूत्रप्रयोजनम्)

(आक्षेपभाष्यम्)

कानि पुनरस्य योगस्य प्रयोजनानि ?

(उद्द्योतः) भाष्ये—कानि पुनरिति । पूर्वमेतत्सूत्रकरणे का युक्तिरिति युक्तिप्रश्नः । इदानीं तु प्रयोजनप्रश्न इति न पौनरुक्त्यम् । अत एव सदन्वाख्यानादिति प्रागुत्तरितम् ॥

(३९१ यथान्याससूत्रे प्रयोजनवार्तिकम् ॥ १ ॥)

॥ * ॥ प्रयोजनमपृक्तश्लिलोपे नुममामौ गुणवृद्धिदीर्घत्वेमडाट्श्नम्विधयः ॥ * ॥

(भाष्यम्)

अपृक्तलोपे श्लिलोपे च कृते नुम्-अमामौ-गुण-वृद्धी-दीर्घत्वं इम्-अडाटौ-श्नम्विधिरिति प्रयोजनानि ॥

(प्रदीपः) प्रयोजनमिति । यद्यप्यल्विध्यर्थमतृणेडित्यादौ, तथापि विशेषविहितत्वान्नुमादयोऽप्यस्यैवोदाहरणानीति भावः ॥

(उद्द्योतः) यद्यप्यल्विध्यर्थमिति । इदमिति शेषः ॥ विशेषविहितत्वादिति । प्रत्ययविषये शीघ्रोपस्थितिकत्वादित्यर्थः ॥

(उदाहरणोपपादनभाष्यम्)

नुम्—अग्ने त्री ते वाजिना त्री षधस्था । ता ता पिण्डानाम् ॥

अमामौ—हे अनड्वन्, अनड्वान् ॥

गुणः—अधोक्, अलेट् ॥

वृद्धिः—न्यमार्ट् ॥

दीर्घत्वम्—अग्ने त्री ते वाजिना त्री षधस्था, ता ता पिण्डानाम् ॥

इम्—अतृणेट् ॥

अडाटौ—अधोक्, अलेट्, ऐयः, औनः ॥

श्नम्विधिः—अभिनोऽत्र, अच्छिनोऽत्र ॥

अपृक्तश्लिलोपयोः कृतयोरेते विधयो न प्राप्नुवन्ति । प्रत्ययलक्षणेन भवन्ति ॥

(प्रदीपः) अनड्वन्निति । पूर्वं संबुद्धिलोपमाश्रित्यैतदुक्तम् ॥ यदि तु विशेषविहितत्वात् 'अम् संबुद्धौ' इति पूर्वमम् प्रवर्तते, तदा संबुद्धिलोपो न स्यात् ॥

पेय इति । इयर्तेर्लेट्-तिप्-शपः श्लुः-द्विर्वचनम् । अर्तिपिपर्त्योश्चेतीत्वम्, अभ्यासस्यासवर्ण इतीयङ् ॥

औन इति । उन्देर्लेट्-सिप्-श्नम्-श्नान्नलोपः-दश्चेति रुत्वम् ॥

(उद्योतः) श्री ते इत्यादौ शेश्छन्दसीति लोपः । नुम्फलं दीर्घः ॥

वाधित्वेति । अपवादबाधकवाचनिकपूर्वविप्रतिषेधाश्रयेणेति भावः । न्यायेन पूर्वं लोपप्राप्तेरल्पविषयत्वात् ॥ विशेषविहितत्वादिति । येन नाप्राप्तिन्यायेनापवादत्वादित्यर्थः ॥ तदेति । अपवादविषयं परित्यज्येति न्यायेनापवादविषये उत्सर्गाप्रवृत्तेरिति भावः ॥ यदीत्यनेन विषयभेदादपवादत्वमेव नास्तीति सूचितम् । यदि तु लुग्विषये प्रतिषेधो वक्तव्य इत्यादिसाप्तमिकभाष्येण विषयभेदेऽप्यपवादत्वं तर्हि प्रत्ययलोपस्थलेऽनुत्पत्तिरेवान्वाख्यायते इति सरूपसूत्रस्थभाष्ये उक्तत्वेनापवादत्वसंभावनैव नेत्याहुः ॥

इतीयङिति । ततो गुणेऽपृक्तलोपेऽडाटाविति भावः ॥ आडागमे रूपान्तरेण तत्तच्छास्त्रनिमित्तविघातात् केनापि कार्येणानयोर्न यौगपद्यमिति भावः ॥ लावस्थायामडिति पक्षेऽपि बहुलं छन्दस्यमाङ्योगेऽपीति बाहुल्कादेवमेव प्रक्रिया बोध्या ॥ अमिनोऽश्रेत्यत्रापीकारलोपापृक्तलोपाभ्यां समो यौगपद्यासम्भवेन परत्वाल्लोपे तत्र प्रवृत्तिरिति बोध्यम् ॥

(प्रत्याख्यानभाष्यम्)

नैतानि सन्ति प्रयोजनानि । स्थानिवद्भावेनाप्येतानि सिद्धानि ॥

(सूत्रावश्यकताभाष्यम्)

न सिध्यन्ति । आदेशः स्थानिवदित्युच्यते । न च लोप आदेशः ॥

(प्रदीपः) **न च लोप इति ।** दिशिरुच्चारणक्रियः । न च लोप उच्चार्यते, अभावरूपत्वात् ॥

(प्रत्याख्यानसाधकभाष्यम्)

लोपोऽप्यादेशः ॥

कथम् ?

आदिश्यते यः स आदेशः, लोपश्चाप्यादिश्यते ॥

(प्रदीपः) **लोपोऽपीति ।** प्रतिपादनक्रियोऽत्र दिशिरिति भावः ॥

(लोपेऽप्यादेशत्वसाधकभाष्यम्)

दोषः खल्वपि स्यात् यदि लोपो नादेशः स्यात् । इह "अचः परस्मिन् पूर्वविधौ" इत्येतस्य योगस्य भूयिष्ठानि लोप उदाहरणानि, तानि न स्युः ॥

(सूत्रारम्भावश्यकताभाष्यम्)

यत्र तर्हि स्थानिवद्भावो नास्ति, तदर्थमयं योगो वक्तव्यः ॥

क्व च स्थानिवद्भावो नास्ति ?

योऽल्विधिः ॥

(आक्षेपभाष्यम्)

किं प्रयोजनम् ?

(प्रयोजनभाष्यम्)

प्रयोजनं ङीनकारलोपेत्त्वेमुविधयः ॥

(उद्योतः) भाष्ये—प्रयोजनं ङाविति । सूत्रारम्भवादी ॥

(सूत्रारम्भदूषणभाष्यम्)

भसंज्ञाङीपुष्फगोरात्वेषु च दोषो भवति ॥

(उद्योतः) प्रत्याख्यानवाद्याह—भसंज्ञेत्यादि ॥

(सूत्रारम्भवादिभाष्यम्)

भसंज्ञायां तावन्न दोषः । आचार्यप्रवृत्तिर्ज्ञापयति—न प्रत्ययलक्षणेन भसंज्ञा भवतीति । यदयम्—"न ङिसंबुद्ध्योः" इति ङौ प्रतिषेधं शास्ति ॥

ङीप्यपि । नैवं विज्ञायते—अणन्तादकारान्तादिति ।

कथं तर्हि ?

अण्योऽकार इति ॥

ष्फेऽ । । नैवं विज्ञायते—यञन्तादकारान्तादिति ।

कथं तर्हि ?

यञ्‌ योऽकार इति ॥

गोरात्वेऽपि । नैवं विज्ञायते—अमि अचीति ।

कथं तर्हि ?

अच्यमीति ॥

(प्रदीपः) **अण्योऽकार इति ।** अकारेणाणन्तं न विशेष्यते, किं तर्ह्यणेव, सर्वथाप्यकार एवेति विशेषणसामर्थ्यात् 'श्रूयमाणाकाररूपादणः' इति विज्ञायते ॥ अथवा—अण्योऽकार इति अणाऽकारो विशेष्यत इति वर्णनिमित्तो ङीप्, न तु प्रत्ययनिमित्त इति प्रत्ययलक्षणाभावः ॥ **यञ्‌ योऽकार इति ।** अकारावयव इत्यर्थः । अथवा—यञवयवे यञ्शब्दोऽत्र वर्तते, यञवयवो योऽकार इत्यर्थः ॥ पूर्ववदेतदपि व्याख्येयम् ॥ **अच्यमीति ।** अच् प्रधानं तद्विशेषणममिति तदादिविध्यभावः । तत्र वर्णनिमित्तमात्वम्, न प्रत्ययनिमित्तमिति दोषाभावः ॥

(उद्योतः) सूत्रारम्भवाद्याह—भसंज्ञायां तावदिति ॥ यदयं न ङीति । अङ्गाधिकारप्रतिनिर्देशपक्षेऽयं ज्ञापकोपन्यासः ॥ अकारेणाणन्तमिति । तद्धि जातेरस्त्रीत्यादेः 'आखुः' इत्यादौ व्यावृत्तये आवश्यकम् ॥ ननु प्रत्ययग्रहणसामर्थ्येन प्रधानतया प्रत्ययत्वेन प्रत्ययस्य यत्र निमित्तता तत्रैवास्त्विध्यर्थमिदम्, एवं चाकाररूपो योऽणित्यर्थेऽपि प्रत्ययलक्षणं दुर्वारमत आह—विशेषणेति ॥ वस्तुतोऽकार एव विशेष्य इत्याह—अणेति ॥ न तु प्रत्ययनिमित्त इति । प्राधान्येन प्रत्ययनिमित्त इत्यर्थः ॥ अज्झलात्मकयञः-अकारेण सामानाधिकरण्यासंभवादाह—अकारावयवेति । बहुव्रीहिः । अस्य विशेषणत्वे इदम्, गुणे त्वन्याय्यकल्पनेति न्यायादिति भावः ॥ नन्वेवं सति मत्यादिष्वतिप्रसङ्गवारणायाजाद्यत इत्यत्र[3] मुख्यार्थस्योत्तरत्र लक्षणायां वैरूप्यं स्यादतो व्याख्यानान्तरमाह—अथवेति ॥ तद्विशेषणमिति । अमोऽवयवेऽचीत्यर्थ इति भावः ॥

(प्रत्याख्यानभाष्यम्)

प्रयोजनान्यपि तर्हि नैतानि सन्ति ॥

(उद्द्योतः) एवं प्रत्याख्यानवाद्युक्तदोषेषु परिहृतेषु प्रत्याख्यानवाद्याह—प्रयोजनान्यपीत्यादि ॥

(दूषणोद्धारभाष्यम्)

यत्तावदुच्यते—ङौ नकारलोप इति ॥

क्रियत एतन्न्यास एव—"न ङिसंबुद्ध्योः" इति ॥

(प्रदीपः) **क्रियत एतदिति** । त्वया ज्ञापनार्थमवश्यं वक्तव्यमिति भावः ॥

(उद्द्योतः) ज्ञापनार्थमिति । प्रत्ययलक्षणेन भत्वं नेत्यस्येति शेषः ॥ न लुमता तस्मिन्नित्यनाभित्येदम् ॥

(दूषणोद्धारभाष्यम्)

इत्त्वमपि । वक्ष्यत्येतत् *शास इत्त्वे आशासः क्वौ* इति ॥

(प्रदीपः) **शास इत्त्व इति** । कृतेऽप्यस्मिन् सूत्रे नियमार्थमेतद्वक्तव्यं 'अशास्त' इत्यादौ मा भूत् । अकृते तु विध्यर्थम् । 'आशास्ते' इत्यादौ तु न भवति, **शासु अनुशिष्टावित्यस्यैव** तत्र ग्रहणात् ॥

(उद्द्योतः) अकृते त्विति । परस्मैपदिविहितात्साहचर्याच्छासुधातोरेव ग्रहणं तत्र—इति पक्षे विध्यर्थम् ॥ नन्वेवमपि 'आर्यशीः' इत्याद्यसिद्धिरिति चेत् । अत्राहुः—शास इति सामान्यसूत्रम्, ततः—अङि, अजादौ चेदङ्येव—इति नियमार्थमिदम् । एवं च सूत्रे हल्ग्रहणं मास्त्विति मित्रशीरित्यादिसिद्धिः ॥ आशासः क्वाविति तु अत्र शासेरेव ग्रहणे विध्यर्थम्, अन्यथा नियमार्थ-इति 'आशास्ते' इत्यादौ न दोष इति ॥

(दूषणोद्धारभाष्यम्)

इत्त्वविधिरपि । हलीति निवृत्तम् ॥

(आक्षेपभाष्यम्)

यदि हलीति निवृत्तं, तृणहानि-अत्रापि प्राप्नोति ॥

(समाधानभाष्यम्)

एवं तर्हि—'अचि न' इत्यनुवर्तिष्यते ॥

(तदस्याक्षेपभाष्यम्)

न तर्हीदानीमयं योगो वक्तव्यः ॥

(उद्द्योतः) अथ वार्तिकोक्तविध्यर्थत्वे दूषिते भाष्यकृत् नियमार्थं सूत्रमिति प्रश्नपूर्वकमाह—न तर्हीत्यादि ॥

(सिद्धान्तिसमाधानभाष्यम्)

वक्तव्यश्च ॥

किं प्रयोजनम् ?

प्रत्ययं गृहीत्वा यदुच्यते तत्प्रत्ययलक्षणेन यथा स्यात् । शब्दं गृहीत्वा यदुच्यते तत्प्रत्ययलक्षणेन मा भूदिति ॥

किं प्रयोजनम् ?

शोभना दृषदोऽस्य सुदृषद् ब्राह्मणः, "सोर्मनसी अलोमोषसी" इत्येष स्वरो माभूदिति ॥ प्रत्ययलोपे प्रत्ययलक्षणम् ॥ ६२ ॥

(प्रदीपः) **प्रत्ययं गृहीत्वेति** । स्थानिवद्भावेन सिद्धे सत्ययं योगो नियमार्थः । प्रत्यय एव यस्य लक्षणं तत्प्रत्ययलोपे यथा स्यात् ॥ 'सोर्मनसी' इत्यत्र तु **अनिनस्मन्ग्रहणानि** चेति वचनादस् प्रत्ययश्चाप्रत्ययश्च गृह्यते इति सुदृषदित्यत्र स्थानिवद्भावाभावादुत्तरपदाद्युदात्तत्वाभावे **नञ्सुभ्याम्**ित्यन्तोदात्तत्वं भवति । तत्र **चोत्तरपदादि**रित्यधिकारादसन्तमुत्तरपदं गृह्यते इति सुदृषदित्यत्र स्थानिवद्भावादसन्तत्वमुत्तरपदस्य स्यात् ॥ ६२ ॥

(उद्द्योतः) प्रत्ययं गृहीत्वेति । प्रत्ययत्वतद्व्याप्यधर्मपुरस्कारेण यदुच्यत इत्यर्थः ॥ शब्दं गृहीत्वेति । उक्तधर्मातिरिक्तपुरस्कारेण यदुच्यत इत्यर्थः ॥ ननु शब्दं गृहीत्वा यदुच्यते तत्प्रत्ययलक्षणेन मा भूत्, स्थानिवत्त्वेन तु स्यादत आह—**स्थानिवदिति** ॥ प्रत्यय एवेति । उक्तोऽर्थः । एतदर्थमेव द्वितीयं प्रत्ययपदम् ॥ न चालोमोषसीति पर्युदासेन श्रूयमाणासन्तस्यैव ग्रहणमिति नियमोऽपि व्यर्थ इति वाच्यम् । पर्युदासेन प्रत्ययासन्तस्यैव ग्रहणापत्तौ सुव इत्यादौ स्वरानापत्तेरिति भाष्याशयात् ॥ ननु स्थानिनिमित्तं यदन्यस्य कार्यं तत्स्थानिवत्त्वेन लोपेऽपि, न तु तस्यैव । असतो वचनशतेनापि कार्यित्वाप्रतिपादनात् । इह चास एव कार्यित्वमत आह—तत्र चेति । सोर्मनसीति सूत्रे इत्यर्थः ॥ ६२ ॥

(५८ प्रत्ययलक्षणनिषेधसूत्रम् ॥ १ । १ । ९ आ. ४ सू.)

न लुमताऽङ्गस्य ॥ १ । १ । ६३ ॥

(न्यूनतापरिहारः)

(३९२ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ लुमति प्रतिषेधे एकपदस्वरस्योपसंख्यानम् ॥ * ॥

(भाष्यम्)

लुमति प्रतिषेधे एकपदस्वरस्योपसंख्यानं कर्तव्यम् ॥ एकपदस्वरे च लुमता लुप्ते प्रत्ययलक्षणं नेति वक्तव्यम् ॥

(प्रदीपः) **न लुमताऽङ्गस्य ॥ ६३ ॥ लुमतीति** । लुमत्संज्ञया प्रतिपादितमदर्शनं-लुमत् । तत्र यः प्रतिषेधः, तस्मिन्नित्यर्थः ॥ **एकपदस्वरस्येति** । एकपदाश्रयो यः स्वरः, तस्येत्यर्थः ॥ यस्तु **पदस्य पदादि**ति पदद्वयाश्रयः स्वरः, तत्र प्रत्ययलक्षणं भवत्येव । दधि तिष्ठति-इति **तिङ्ङतिङ** इति निघातः ॥ **अङ्गस्ये**त्यत्राधिकारनिर्देशात् ञ्निति कित्स्वरस्य चानाङ्गत्वात्प्रतिषेधस्याप्राप्तिरिति भावः ॥

(उद्द्योतः) न लुमता० ॥ ६३ ॥ लोपक्रियानिरूपिता करणे तृतीया । यद्यपि लुशब्दयोगात्संज्ञा लुमद्वाच्या । न च तत्रायं प्रतिषेधः, किंतु तत्प्रतिपादितादर्शने । एवं च लुमति प्रतिषेध इत्यनुपपन्नम्, तथापि वाचकधर्मस्य वाच्य उपचार इत्याह—लुमदिति ॥ ननु सर्वोऽपि स्वरः कार्यित्वेनैकमेव पदं गृह्णातीत्यत आह—एकेति । सर्वामन्त्रितेत्यत्रामन्त्रितपदेनाष्टमिकमपि[६] ग्रहीतुं शक्यमिति पदस्य

पदादित्यधिकारेऽनन्तरमप्यामन्त्रितस्येत्युक्तस्य व्यवहितमुदाहरति—दधीति ॥ अङ्गस्येत्यधिकारेति । वस्तुतस्तदनिर्देशेऽप्यावश्यकमेतत् । तथाहि—सौवर्गाणां सप्तमीनां भीही···मदेति सूत्रे प्रत्ययात्पूर्वमिति पूर्वग्रहणेन तदन्तसप्तमीत्यस्य पाष्ठभाष्ये तत्सूत्रे एवोक्तत्वेन स्वराणां प्रत्यये परतः पूर्वकार्यत्वाभावात्, कित्स्वरे षष्ठ्या एव सत्त्वाच्च ॥ ननु संज्ञायामुपमानमिति 'उपमानशब्दः संज्ञायामाद्युदात्तः' इत्यर्थकं कनो लुपि चञ्चेव—चञ्चेत्यादावाद्युदात्तसाधकं ञ्नित्यादिरित्येव सिद्धे व्यर्थं सदनुबन्धलक्षणे स्वरे प्रत्ययलक्षणाभावज्ञापकमिति तत्सूत्रे भाष्ये स्पष्टम्, तेनेदं विरुध्येतेति चेन्न । प्रकृतसूत्रे वार्तिकव्याख्यानमात्रं, षष्ठे तु प्रत्याख्यातानीमानीत्यविरोधात् । अत एव तत्र भाष्ये पथिमथिस्वरार्थं वचनं कर्तव्यमित्युक्तम् । एवं च तदर्थस्यात्रत्यवचनस्य कर्तव्यत्वं वदताऽन्येषामकर्तव्यत्वमर्थादुक्तमेव ॥ एतेन भीहीति ज्ञापकं विशेषापेक्षं—सप्तम्यर्थग्रहणे तदन्तग्रहणे च यत्र फलभेदस्तद्विषयम् । एवं चोपोत्तमं रितीत्यादावेव तत्प्रवृत्तिरिति न ञ्नित्यादिरित्यादौ तत्प्रवृत्तिरिति कैयटाशय इति परास्तम् । संज्ञायामुपमानमिति सूत्रस्थभाष्यविरोधात् । तस्मात् ज्ञापकस्य सामान्यापेक्षत्वमेवोचितम् । तत्र सप्तम्या यथाश्रुतत्वे हि न लुमतेति निषेधात्तदप्राप्तौ ञ्नित्सीति प्रयोजनमिति भाष्यासङ्गतिः स्पष्टैव । न चाङ्गाधिकारमविनिर्देशपक्षे तद्भाष्यं, सिद्धान्तपक्षे योजयितुं शक्यत्वादिति दिक् ॥

(प्रत्याक्षेपभाष्यम्)

किमविशेषेण ?

(प्रत्याक्षेपसमाधानभाष्यम्)

नेत्याह ॥

(१९४ आक्षेपशेषवार्तिकम् ॥ २ ॥)

॥*॥ सर्वामन्त्रितसिज्लुक्स्वरवर्जम् ॥*॥

(भाष्यम्)

सर्वस्वरमामन्त्रितस्वरं सिज्लुक्स्वरं च वर्जयित्वा ॥

(उदाहरणोपपादनभाष्यम्)

सर्वस्वर । सर्वस्तोमः । "सर्वस्य सुपि" इत्याद्युदात्तत्वं यथा स्यात् ॥

(प्रदीपः) **सर्वस्तोम इति । सर्वस्य सुपीति** यदाद्युदात्तत्वं तदेव च **बहुव्रीहौ प्रकृत्येति** विधीयत इत्येकपदस्वरो भवत्येव ॥

(उद्योतः) षष्ठीसमासादौ परत्वात्सतिशिष्टत्वाच्च समासान्तोदात्तत्वस्यैव प्राप्तेर्भाष्ये **सर्वस्तोम** इति बहुव्रीहिरुदाहृतः । तत्र बहुव्रीहिस्वरस्य द्विपदाश्रयत्वात्प्रतिषेधस्यैवाप्राप्तेः कथं तदपवादे इदमुदाहरणमत आह—**सर्वस्येति** ॥ **विधीयत इति** । अपवादनिवर्तनेन व्यवस्थाप्यत इत्यर्थः ॥

(उदाहरणोपपादनभाष्यम्)

आमन्त्रितस्वर । सर्पिरागच्छ, सप्तागच्छत । "आमन्त्रितस्य च" इत्याद्युदात्तत्वं यथा स्यात् ॥

(प्रदीपः) **सर्पिरिति । सर्पिःशब्दोऽन्तोदात्तः** प्रत्ययस्वरेण, घृतादित्वाद्वा । सप्तशब्दोऽपि घृतादित्वादन्तोदात्तः । नित्स्वरेण त्वाद्युदात्तत्वे विशेषो न स्यात् ॥

(उद्योतः) **प्रत्ययस्वरेणेति** । इसिप्रत्ययान्तत्वादिति भावः ॥ मध्विषयस्येत्यस्य तु न प्राप्तिः, **अनिसन्तस्येति** पर्युदासात् ॥ घृतादित्वकल्पनं तु किमर्थमिति चिन्त्यम् ॥ **नित्स्वरेणेति** । सप्तन्शब्दो हि सप्यशूभ्यां तुट्चेति कनिन्नन्तः ॥ **ञ्नः** सङ्ख्याया इत्यप्याद्युदात्तत्वं प्राप्नोतीति द्रष्टव्यम् ॥

(उदाहरणोपपादनभाष्यम्)

सिज्लुक्स्वर । मा हि दाताम्, मा हि धाताम् । "आदिः सिचोऽन्यतरस्याम्" इत्येष स्वरो यथा स्यात् ॥

(प्रदीपः) **मा हि दातामिति । गातिस्थाघ्विति** सिचो लुक्, लेरेव लुकि विधातव्ये सिचो लुग्विधानं प्रत्ययलक्षणार्थम् ॥

(उद्योतः) **मा हि दातामित्यत्राद्प्रतिषेधाय माङ्** । हिशब्दो **हि चेति** निघातप्रतिषेधार्थः ॥ सिज्लुक्स्वरवर्जनं न कार्यमित्याह—**लेरिति** । गातीत्यनेन लेरेव लुकि मन्त्रे घसेत्यत्र पुनर्लिग्रहणं न कार्यम् । लुङ्लेघावात इत्येतच्च विध्यर्थं स्यादिति लाघवमिति भावः ॥ **प्रत्ययलक्षणार्थमिति** । प्रत्ययलक्षणेन सिज्निमित्तकार्यार्थमित्यर्थः ॥

(भाष्यम्)

किं प्रयोजनम् ?

(१९५ प्रयोजनवार्तिकम् ॥ ३ ॥)

॥*॥ प्रयोजनं ञ्निकिल्लुकि स्वराः ॥*॥

(भाष्यम्)

ञ्नित्किस्वरा लुकि प्रयोजयन्ति । गर्गाः-वत्साः-विदाः-उर्वाः-उष्ट्रग्रीवा वामरज्जुः । "ञ्नित्ति" इत्याद्युदात्तत्वं मा भूदिति ॥ इह च—अत्रयः । "कितः" इत्यन्तोदात्तत्वं मा भूदिति ॥

(प्रदीपः) **ञ्निकिल्लुकीति** । इकार उच्चारणार्थः ञ्नित्किताम् प्रत्ययानां लुकि कृते स्वरा निवर्त्यमानतया प्रयोजनमिति पदानां संबन्धः ॥ भाष्यकारस्तु वस्त्वर्थं व्याचष्टे—**ञ्नित्किस्वरा इति** । प्रतिषेधमित्यध्याहारः ॥ **उष्ट्रग्रीवा वामरज्जुरिति** । देवपथादित्वात्कनो लुप् । असंज्ञायां चेदमुदाहरणम् । संज्ञायां तु **संज्ञायामुपमानमिति** भवितव्यमाद्युदात्तत्वेन ॥ **अत्रय इति** । राशदिभ्यां त्रिप्, 'अदेस्त्रिनिश्च' इति त्रिबन्तोऽत्रिशब्द आद्युदात्तः ॥

(उद्योतः) ननु ञ्निकित्स्वरा इति भाष्यदर्शनाद् ञ्निकितां स्वरविशेषणत्वेन लुका समासोऽनुपपन्न इत्यत आह—**ञ्नित्कितामिति** ॥ प्रयोजयन्तीत्यस्य कर्माकाङ्क्षायामाह—**प्रतिषेधमिति** ॥ **लुकीति** । वार्तिके लुकीत्युपलक्षणमिति भावः ॥ भाष्ये—**आद्युदात्तत्वं मा भूदिति** । एवं च प्रातिपदिकादिस्वरेणान्तोदात्तत्वमेवेति भावः ॥ अत्रिशब्दादित्रश्चानिञ इति ढकोऽत्रिभृगुवेति लुक् ॥ नन्वत्रय इत्यत्र कित्स्वरप्रयुक्तान्तोदात्तत्वाभावेऽपि

प्रातिपदिकस्वरेण तत्त्वं दुर्वारमत आह—राशब्दीति ॥ प्रियस्व इति । नान्तस्यान्तोदात्त इति भावः ॥ इदं प्रयोजनं क्विबादिनान्तस्यान्त उदात्त इत्यर्थे बोध्यम् । किन्तु प्रत्ययस्यैवान्तोदात्तत्वे तु प्रत्ययलक्षणेन कार्यिणोऽसंपादनान्न दोषः ॥ अत एव नखनिर्भिन्न इत्यत्रेत्याहुः ॥

(३९६ प्रयोजनान्तरवार्तिकम् ॥ ४ ॥)

॥*॥ पथिमथोः सर्वनामस्थाने लुकि ॥*॥

(भाष्यम्)

पथिमथोः सर्वनामस्थाने लुकि प्रयोजनम् ॥ लुमता लुप्ते प्रत्ययलक्षणं न भवतीति वक्तव्यम् । पथिप्रियः, मथिप्रियः । "पथिमथोः सर्वनामस्थाने" इत्येष स्वरो मा भूदिति ॥

(प्रदीपः) **पथिप्रियः, मथिप्रिय इति** । पूर्वपदप्रकृतिस्वरेणान्तोदात्तौ पथिमथिशब्दौ भवतः ॥

(उद्योतः) पथिमथिशब्दौ इनिप्रत्ययान्ततया प्रत्ययस्वरेण, फिषोऽन्त इति वाऽन्तोदात्तौ । तयोः सर्वनामस्थाननिमित्तमाद्युदात्तत्वमत्रापि स्यादित्यर्थः ॥

(३९७ आक्षेपवार्तिकम् ॥ ५ ॥)

॥ * ॥ अह्नो रविधौ ॥ * ॥

(भाष्यम्)

अह्नो रविधाने लुमता लुप्ते प्रत्ययलक्षणं न भवतीति वक्तव्यम् ॥ अहर्ददाति, अहर्भुङ्क्ते । "रोऽसुपि" इति प्रत्ययलक्षणेन प्रतिषेधो मा भूदिति ॥

(प्रदीपः) **अहर्ददातीति** । असुपीति प्रसज्यप्रतिषेधः । पर्युदासे तु दीर्घाह्ना निदाघ इत्यत्रापि सुप्सदृशे निदाघशब्दे परतो रत्वं स्यात् । रत्वं चेष्यते । लोपशब्देन सोर्लुप्तत्वात्प्रत्ययलक्षणेन सुपि नेति रत्वप्रतिषेधाद्रुत्वे यत्वे तस्य च लोपे दीर्घाह्ना निदाघ इति सिध्यति ॥ लुकि तु प्रत्ययलक्षणप्रतिषेधात् रत्वे सति उत्वाभावादहर्ददातीत्यादि सिध्यति ॥

(उद्योतः) भाष्ये-प्रतिषेधो मा भूदिति । तेनापर्युदासत्वं सूचितम् ॥ तदुपपादयति-पर्युदासे तु इति । प्रत्ययत्वेन सुप्सादृश्ये तु अहर्ददातीत्यत्रापि रत्वं न स्यादित्यर्थः ॥ नन्विष्यमाणमपि रत्वं न प्राप्नोति, प्रत्ययलक्षणनिषेधेन रुत्वस्यैव प्राप्तेरत आह—लोपशब्देनेति । हल्ङ्यादिसूत्रेणेति भावः । लुमता लुप्त एव स निषेध इति तात्पर्यम् ॥ न लुमता तस्मिन्निति पक्षे तु नेदमावश्यकम् ॥

(३९८ आक्षेपवार्तिकम् ॥ ६ ॥)

॥*॥ उत्तरपदत्वे चापदादिविधौ ॥*॥

(भाष्यम्)

उत्तरपदत्वे चापदादिविधौ लुमता लुप्ते प्रत्ययलक्षणं न भवतीति वक्तव्यम् । परमवाचा, परमवाचे, परमगोदुहा, परमगोदुहे, परमश्वलिहा, परमश्वलिहे । पदस्येति प्रत्ययलक्षणेन कुत्वादीनि मा भूवन्निति ॥

अपदादिविधाविति किमर्थम् ?

दधिसेचौ, दधिसेचः । "सात्पदाद्योः" इति प्रतिषेधो यथा स्यात् ॥

(प्रदीपः) **उत्तरपदत्वे चेति** । उत्तरपदम्-उत्तरशब्देनोच्यते, पदैकदेशलोपात् । तेनोत्तरपदस्य पदत्वे=पदव्यपदेशे कर्तव्ये प्रत्ययलक्षणं न भवतीत्यर्थः ॥ **परमवाचेति** । समासार्था या विभक्तिः कृता, तां प्रत्ययलक्षणेनाश्रित्य पदत्वनिबन्धनानि कुत्वादीनि प्राप्नुवन्ति । भसंज्ञा तु **यस्माद् यजादिविधिरिति** समुदायस्यैव, न त्ववयवस्य ॥ **दधिसेचाविति** । दध्नः सेचाविति षष्ठीसमासः । उपपदसमासे तु प्राक्सुबुत्पत्तेः समासविधानात्सेचशब्दस्य पदसंज्ञाया अभावात्पदादित्वं सकारस्य न स्यात् । अनभिधानात् सोपपदाद्विजभावाद्दधिसेचावित्यादिप्रयोगाभावात् ॥

(उद्योतः) उत्तरपदत्वे च-इति सर्वथा कार्यम् ॥ ननु सामान्यत 'उत्तरस्य पदत्वे' इत्यर्थे 'परमं चर्म' इत्यत्रापि निषेधापत्तौ नलोपो न स्यात्, अत आह—उत्तरपदमिति । अत एव बहुव्रपूर्वस्य नेति वचनमर्थवदिति भावः । उत्तरपदशब्दश्च समासचरमावयवे रूढ इत्यसमासे नातिप्रसङ्ग इति बोध्यम् ॥ **समासार्थेति** । तत्र सुप्सुपेत्यधिकारादिति भावः ॥ **तां-सुपोत्पत्तिमित्यत्र** सुपाम् ॥ कुत्वादीनि-कुत्वघत्वढत्वानि ॥ ननु भत्वेन पदत्वबाधोऽत आह—यस्मादिति । तथा च भिन्नावधित्वान्न बाध्यबाधकभाव इति भावः ॥ भाष्ये-पदस्येति । पदस्येत्यधिकृत्य यानि विहितानीत्यर्थः ॥ ननु सोपपदात्सिचेर्विच्चि 'दधिषेचौ' इति स्यादेव । न चेष्टापत्तिः, पदादावित्विति पक्षे दुर्लभत्वात्, अत आह—अनभिधानादिति । तस्य छान्दसत्वादिति भावः ॥

(आक्षेपभाष्यम्)

यद्यपदादिविधावित्युच्यते, उत्तरपदाधिकारो न प्रकल्प्येत ॥

तत्र को दोषः ?

"कर्णो वर्णलक्षणात्" इत्येवमादिविधिर्न सिध्यति ॥

(प्रदीपः) **कर्णो वर्णलक्षणादिति** । नन्वपदादिविधावित्युच्यते, स्वरश्चाऽयं पदादिविधिः । ककारोऽत्रादिः, न स्वकार इत्यदोषः । स्वरविधौ व्यञ्जनमविद्यमानवत्, न त्वादिव्यपदेशे । सूत्रे चासमासार्थं स्यात् । कर्णशब्दादर्शआदित्वादचि कृते 'शुक्लः कर्णः' इत्याद्युदात्तत्वं यथा स्यात् ॥

(उद्योतः) भाष्ये-यद्यपदादीति । एकदेशेन संपूर्णं वार्तिकमुपलक्ष्यते । यतः प्रतिषेधस्यातिव्याप्तिः, न प्रतिषेधापवादस्येति बोध्यम् ॥ **स्वरश्चेति** । उत्तरपदादिरित्यधिकारादिति भावः ॥ नन्वसमासे स्वाङ्गशिटामिति कर्णस्याद्युदात्तत्वं सिद्धमेवेत्यत आह—कर्णशब्दादिति ॥ एवमादिविधिर्न सिध्यतीति भाष्यादुत्तरपदादिरित्यधिकारस्थसूत्राणां वैयर्थ्यस्यैव दूषणत्वेन प्रतीतिरित्येके ॥

(आक्षेपबाधकन्यासान्तरभाष्यम्)

यदि पुनः * नलोपादिविधौ इत्युच्यते * लुमता

लुप्ते प्रत्ययलक्षणं न भवतीत्युच्येत ॥

(प्रदीपः) यदि पुनरिति । तेन पूर्वस्मिन् परत्र च भवत्येव प्रत्ययलक्षणम् ॥

(न्यासान्तरनिराकरणभाष्यम्)

नैवं शक्यम् । इह हि-राजकुमार्यौ-राजकुमार्य इति शाकलं प्रसज्येत ॥

(प्रदीपः) राजकुमार्याविति । इकोऽसवर्णे इत्यत्रेङः पदान्तादतीत्यतः पदान्तग्रहणमनुवर्तते । तत्र प्रत्ययलक्षणेन पदान्तत्वाच्छाकलप्रसङ्गः ॥

(न्यासान्तरसाधकभाष्यम्)

नैष दोषः । यदेतत्—*सिति शाकलं न* इति, एतत्—*प्रत्यये शाकलं न*इति वक्ष्यामि ॥

(आक्षेपभाष्यम्)

यदि "प्रत्यये शाकलं न" इत्युच्यते, 'दधि अधुना-मधु अधुना' अत्राऽपि न प्रसज्येत ॥

(प्रदीपः) दधि अधुनेति । अधुनाप्रत्यय इदमो विधीयते । तत इदम इश् । यस्येति चेति लोपः ॥

(निराकरणभाष्यम्)

प्रत्यये शाकलं न भवति ।

कतरस्मिन् ?

यस्मात्पः प्रत्ययो विहित इति ॥

(प्रदीपः) यस्माद्य इति । प्रत्यासत्त्येति भावः ॥ राजकुमार्यावित्यत्र यद्यपि समुदायाद्विहितः, तथाप्यवयवादप्यसौ विहित इति बुद्धिर्भवत्येव । समुदायद्विर्वचनेऽवयवद्विर्वचनबुद्धिवत् ॥

(उद्योतः) प्रत्यासत्त्येति । प्रत्ययग्रहणे यस्मात् स विहितस्तदादेरित्युपस्थितेति भावः ॥ तथापीति । वस्तुतो राजकुमार्यावित्यत्रापि दोषः, समुदायादसौ विहितो नावयवात् । अन्यथा 'कौरव्येयः' इत्यादौ चकाराकारस्यापि वृद्धिः स्यात् ॥ इह तर्हीत्यादिभाष्यं तु अभ्युपेत्यवादेन । इुंवरम्भे तु न उत्तरपदस्येचेत्यस्य प्रवृत्तिः । अत एव पूर्वमेव दोषेणेदं दूषितं भगवतेति बोध्यम् ॥ ङ्मो ह्रस्वादिति सूत्रस्थभाष्यं त्वेकदेश्युक्तिरिति न दोष इति तत्रैव निरूपयिष्यामः ॥

(आक्षेपभाष्यम्)

इह तर्हि-परमदिवा, परमदिवे । "दिव उत्" इत्युत्वं प्राप्नोति ॥

(प्रदीपः) उत्वमिति । उत्वविधावेङः पदान्तादिति पदाधिकारः ॥

(विशेषानभ्युपगमभाष्यम्)

अस्तु तर्ह्यविशेषेण ॥

(आक्षेपस्मारणभाष्यम्)

ननु चोक्तम्—उत्तरपदाधिकारो न प्रकल्पेतेति ॥

(परिहारभाष्यम्)

वचनादुत्तरपदाधिकारो भविष्यति ॥

(प्रदीपः) वचनादिति । समासे सति उत्तरपदं भवति । न च कणशब्दोऽच्प्रत्ययान्तोऽस्ति, अर्शआदिषु हि स्वाङ्गाद्धीनादिति पठ्यते । तेन स्वाङ्गादिभ्य एव हीनस्वाङ्गवाचिभ्यो भवति । न च कर्णशब्दो हीनस्वाङ्गवाची ॥

(उद्योतः) समासचरमावयवे उत्तरपदशब्दो रूढ इत्यभिप्रेत्याह—समासे हीति । न तु पदत्वमपि तद्व्यवहारे प्रयोजकमित्यर्थः ॥ केवलरूढत्वे मानमुक्तम्, तुष्यतुदुर्जनन्यायेन केवलयोगेऽप्याह—न च कर्णेति । राजवाचककर्णशब्दस्य तु अभिव्यक्तपदार्था ये इति न्यायान्न तत्र ग्रहणमिति भावः ॥ काश्यपिनावित्यादौ छन्दोब्राह्मणानीति तद्विषयताबोधकशास्त्रबलात् सुबुत्पत्तेः प्रागेव तद्धित इति न दोषः ॥

(आक्षेपभाष्यम्)

तर्हि वक्तव्यम् ॥

(प्रदीपः) तत्तर्हीति । उत्तरपदत्वे चापदादिविधावित्येतत् ॥

(समाधानभाष्यम्)

न वक्तव्यम् । अनुवृत्तिः करिष्यते । इदमस्ति—"यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्", "सुप्तिङन्तं पदम्", यस्मात्सुप्तिङ्विधिस्तदादि सुबन्तं तिङन्तं च ॥ "नः क्ये" नान्तं क्ये पदसंज्ञं भवति, यस्मात् क्यविधिस्तदादि सुबन्तं च ॥ "सिति च", सिति पूर्वं पदसंज्ञं भवति, यस्मात्सिद्विधिस्तदादि सुबन्तं च ॥ "स्वादिष्वसर्वनामस्थाने", स्वादिष्वसर्वनामस्थाने पूर्वं पदसंज्ञं भवति, यस्मात्स्वादिविधिस्तदादि सुबन्तं च ॥ "यचि भम्", यजादिप्रत्यये पूर्वं भं भवति, यस्माद्यजादिविधिस्तदादि सुबन्तं च ॥

(प्रदीपः) यचि भमिति । ततश्च परमवाचेत्यत्र वाक्शब्दस्य भत्वात्पदत्वाभावः ॥

(उद्योतः) भाष्ये—नः क्ये इत्यादि-तदादिसुबन्तं चेति । यस्मात्प्रत्ययविधिरिति अवश्यमुत्तरत्रानुवर्त्यम्, परमैश्चतुर्भिरित्यादौ परमघटितसमुदायस्य पदत्ववारणाय । तत्त्वे हि झल्युपोत्तममिति परमैरित्यस्यापि निघातापत्तिः । एवं च तस्य नः क्ये इत्यत्रापि संबन्धे यस्मात् क्यविधिस्तदादि । यदि क्ये तन्निमित्तान्तर्वर्तिसुपा पदं तदा नान्तमेवेति नियमः स्यात् । तथा च 'परमवाच्यति' इत्याद्यवयववाक्शब्दस्य पदत्वेन कुत्वं स्यात् । सूत्रं तु 'समिध्यति' इत्येतद्व्यावृत्त्यर्थं स्यादिति सुबन्तमित्यपि संबध्यत इति भावः । तस्य च मध्ये चेत् सुबन्तं तदा तदपि नान्तमेव पदमित्यर्थः ॥ अन्वाचयशिष्टं च सुबन्तमिति सर्वत्र । संनियोगशिष्टत्वे 'पद्भ्यः' इत्याद्यसिद्धिः ॥ सिति चेत्यत्र यद्यपि नास्योपयोगः, अवयवसुबन्ताप्रसिद्धेः; तथापि उत्तरत्रानुवृत्तिं दर्शयितुं तत्रापि तत्संबन्धो दर्शितः । व्यपदेशिवद्भावेन कथंचिदन्वयः संपाद्यः । एवं स्वादिष्विति सूत्रेऽपि तदनुवृत्तिकरणमुत्तरार्थमेव । यचि भमित्यत्रापि पदसंज्ञया तुल्यावधिकत्वसिद्ध्यर्थं यस्मादित्याद्यनुवर्त्यमिति बोध्यम् ॥

(आक्षेपभाष्यम्)

इह तर्हि-परमवाक् । 'असर्वनामस्थाने' इति प्रतिषेधः प्राप्नोति ॥

(प्रदीपः) इह तर्हीति । 'असर्वनामस्थाने' इति प्रसज्यप्रतिषेधं मन्यते । ततश्च सर्वनामस्थाने परतो यस्मात् स्वादिविधिस्तदादि सुबन्तं च पदसंज्ञं न भवतीति प्रत्ययलक्षणेन सर्वनामस्थानपरत्वात् पदत्वप्रतिषेधात् कुत्वाप्राप्तिः ॥

(समाधानभाष्यम्)

अस्तु तस्याः प्रतिषेधः—या स्वादौ पदमिति पदसंज्ञा । या तु सुबन्तं पदमिति पदसंज्ञा सा भविष्यति ॥

(आक्षेपभाष्यम्)

सत्येतत्प्रत्यय आसीत्—अनया भविष्यत्यनया न भविष्यतीति ॥ लुप्ते इदानीं प्रत्यये यावत एवावधेः स्वादौ पदमिति पदसंज्ञा, तावत एवावधेः सुबन्तं पदमिति । अस्ति च प्रत्ययलक्षणेन सर्वनामस्थानपरतेति कृत्वा 'प्रतिषेधाश्च बलीयांसो भवन्ति' इति प्रतिषेधः प्राप्नोति ॥

(प्रदीपः) सत्येतदिति । अवधिभेदात्संज्ञिनां भेदात् ॥ बलीयांस इति । विध्युन्मूलनरूपत्वात् ॥

(उद्योतः) संज्ञिनां भेदादिति । सति सौ तदन्तस्य सुबन्तमिति पदत्वम्, तत्प्राग्भागस्य स्वादिष्विति भावः ॥ ननु अपरनिमित्तकत्वेनान्तरङ्गतया सुबन्तमिति पदत्वं स्यादत आह भाष्ये—प्रतिषेधाश्चेति । विध्युन्मूलनम्—प्राप्तस्य विधेर्निवर्तनम् ॥ एवं चापवादन्यायेनाप्यन्तरङ्गासंभव इति भावः ॥ अत्रानुवर्तमानं सुबन्तमित्यपि स्वादिष्विति सूत्रेण तदनुवृत्त्या मध्यस्य सुबन्तस्य यत्प्राप्तं तन्निषेधकम्, न तु सुबन्तमितिसूत्रप्राप्तस्येति बोध्यम् ॥

(समाधाने भाष्यवार्तिकम्)

॥ नाप्रतिषेधात् ॥

(भाष्यम्)

नायं प्रसज्यप्रतिषेधः—सर्वनामस्थाने नेति । किं तर्हि ?

पर्युदासोऽयम्—यदन्यत्सर्वनामस्थानादिति । सर्वनामस्थाने अव्यापारः । यदि केनचित्प्राप्नोति तेन भविष्यति । पूर्वेण च प्राप्नोति ॥

(समाधाने भाष्यवार्तिकम्)

॥ अप्राप्तेर्वा ॥

(भाष्यम्)

अथवा—अनन्तरा या प्राप्तिः सा प्रतिषिध्यते । कुत एतत् ?

अनन्तरस्य विधिर्वा भवति प्रतिषेधो वेति । पूर्वा प्राप्तिरप्रतिषिद्धा तया भविष्यति ॥

(आक्षेपभाष्यम्)

ननु चेयं प्राप्तिः पूर्वां प्राप्तिं बाधते ॥

(समाधानभाष्यम्)

नोत्सहते प्रतिषिद्धा सती बाधितुम् ॥

(उद्योतः) भाष्ये—नोत्सहत इति । स्वयमप्रवर्तमाना कथमन्यं बाधेतेति भावः ॥

(आक्षेपभाष्यम्)

यद्येवं, परमवाचौ-परमवाच इति "सुप्तिङन्तं पदम्" इति पदसंज्ञा प्राप्नोति ॥

(समाधानभाष्यम्)

एवं तर्हि योगविभागः करिष्यते—"स्वादिषु" पूर्वं पदसंज्ञं भवति ॥ ततः—"सर्वनामस्थाने अयचि" पूर्वं पदसंज्ञं भवति ॥ ततो—"भम्" संज्ञं भवति यजादावसर्वनामस्थान इति ॥

(प्रदीपः) एवं तर्हीति । योगविभागे सति सर्वा प्राप्तिः प्रतिषिध्यत इति दोषाभावः ॥ 'असर्वनामस्थाने' इति नञः क्रियापदेन सम्बन्धादुत्तरपदेनासम्बन्धः, यचीत्येतच्च सर्वनामस्थानविशेषणम् । तेनायमर्थो भवति—यजादौ सर्वनामस्थाने परतः पदसंज्ञा न भवतीति । हलादौ तु सुपन्दे भवत्येव । भाष्ये तु वस्तुमात्रमुपन्यस्तम्—सर्वनामस्थाने अयचीति । यजादौ सर्वनामस्थाने पदसंज्ञाया निषेधात्सामर्थ्यादयमर्थः संपद्यते—अयजादौ सर्वनामस्थाने पदसंज्ञा भवतीति ॥

(उद्योतः) ननु सर्वनामस्थानेऽयचीति न्यासस्य पदत्वनिषेधकत्वेऽनन्तरस्येति न्यायेन स्वादिष्वित्यस्यैव निषेधे परमवाचावित्यादौ सुबन्तमिति पदत्वं स्यादत आह—योगविभागे इति । एवं च तस्सामर्थ्यादनन्तरस्येति न्यायबाध इति भावः ॥ यचीत्यस्य पुरस्तादपकर्षे फलमाह—हलादाविति । वस्तुमात्रम्—अर्थसिद्धोऽर्थः । तत्फलं नञः सर्वनामस्थानपदेनासंबन्धप्रदर्शनम् ॥

(आक्षेपभाष्यम्)

यदि तर्हि—सावपि पदं भवति, एचः प्लुतविकारे पदान्तग्रहणं चोदयिष्यति, इह मा भूत्—भद्रं करोषि गौरिति । तस्मिन् क्रियमाणेऽपि प्राप्नोति ॥

(उद्योतः) भाष्ये-प्लुतविकारे इति । प्लुतसहितविकारे इत्यर्थः । एचोऽप्रगृह्यस्यादूराद्धूते पूर्वस्यार्धस्यादुत्तरस्येदुतावित्यत्रेति भावः ॥

(समाधानभाष्यम्)

वाक्यपदयोरन्त्यस्येत्येवं तत् ॥

(प्रदीपः) वाक्यपदयोरिति । गौरित्यौकारो वाक्यान्तो न भवतीत्यदुतौ न भवतः ॥

(आक्षेपभाष्यम्)

इह तर्हि—दधिसेचौ-दधिसेचः-इति "सात्पदाद्योः" इति पदादिलक्षणः षत्वप्रतिषेधो न प्राप्नोति ॥

(उद्योतः) भाष्ये—इह तर्हीति । वार्तिकारम्भे तु अपदादिविधावित्युक्तेर्न दोषः ॥ प्रत्याख्याने तु दोषः । कुत्वाभावाय पदत्वनिषेधप्रवृत्तेरावश्यकत्वात् । एतेन योगविभागसिद्धस्य काचित्कत्वाच्च दोष इत्यपास्तमिति भावः ॥

(समाधानभाष्यम्)

मा भूदेवम्—पदस्यादिः - पदादिः, पदादेर्नेति ॥

कथं तर्हि ?

पदादादिः - पदादिः, पदादेर्नेत्येवं भविष्यति ॥

(प्रदीपः) पदादादिरिति । पञ्चमीति योगविभागात्समासः ॥

(उद्योतः) पञ्चमीति योगविभागादिति । पदादित्यस्य परशब्दान्वयेनासामर्थ्यादत्र समासशास्त्राप्राप्तेः सौत्रः समास इति वक्तुमुचितम् ॥

(आक्षेपभाष्यम्)

नैवं शक्यम् । इहापि प्रसज्येत—ऋक्षु - वाक्षु - त्वक्षु - कुमारीषु - किशोरीष्विति ॥

(समाधानभाष्यम्)

सात्पतिषेधो ज्ञापकः—स्वादिषु पदत्वेन येषां पदसंज्ञा, न तेभ्यः प्रतिषेधो भवतीति ॥

(उद्योतः) भाष्ये—न तेभ्यः प्रतिषेध इति । तेभ्यः परस्य सुबन्तं पदमिति पदत्वमाश्रित्यापि न प्रतिषेध इत्यर्थः ॥ अत एव परमवाक्षु इत्यादावपि न दोषः ॥

(आक्षेपभाष्यम्)

इह तर्हि—'वहुसेचौ, वहुसेचः' वहुजयं प्रत्ययः । अत्र पदादादिः - पदादिः, पदादेर्नेत्युच्यमानेऽपि न सिध्यति ॥

(उद्योतः) भाष्ये—पदादादेर्नेत्युच्यमानेऽपीति । षष्ठीतत्पुरुषेऽपि न सिध्यति, कुत्वाभावाय पदत्वाभावस्यावश्यकत्वात्—इति भावार्थः । अयं वहुसेचि दोषो वार्तिकारम्भेऽपि, उत्तरपदत्वाभावेन निषेधाप्राप्त्या परत्वसत्त्वेन षष्ठीतत्पुरुषेण षत्वनिषेधसाम्राज्येऽपि कुत्वप्राप्तेः ॥

(वार्तिकन्यासान्तरेण समाधानभाष्यम्)

एवं तर्हि—

(वार्तिकन्यासभाष्यम्)

॥ "उत्तरपदत्वे च पदादिविधौ ॥

(भाष्यम्)

लुमता लुप्ते प्रत्ययलक्षणं भवति" इति वक्ष्यामि, तन्नियमार्थं भविष्यति—पदादिविधावेव, न पदान्तविधाविति ॥

(उद्योतः) इदानीं प्रत्याख्यानप्रकारस्य गौरवदुर्ज्ञेयत्वाभ्यामरुचत्वं मनसि निधाय लाघवाय नञ्रहितवचनपाठमाह—एवं तर्हीति ॥ न पदान्तविधाविति । पदान्तस्थानिके विधावित्यर्थः ॥ नञ्घटितवार्तिकस्याप्यत्रैव प्रवृत्तिर्व्याख्यानादेतदेकफलत्वाचेति बोध्यम् ॥

(आक्षेपभाष्यम्)

कथं—वहुसेचौ - वहुसेचः - इति ?

(प्रदीपः) कथं वहुसेचाविति । समासाभावान्नोत्तरस्य पदत्वम्, नापि पूर्वस्य पदत्वम् ॥

(उद्योतः) एतावताऽपि वहुसेचावित्यस्यासिद्धिरिति शङ्कते—कथं वहुसेचाविति ॥ तदुपपादयति—समासेति । एवं च नियमाप्राप्तौ प्रत्ययलक्षणेन पदत्वात् षत्वनिषेधवत् चोः कुः पदान्तस्येति कुत्वं स्यादिति भावः ॥ पञ्चमीसमासेऽपि षत्वापत्तिरित्याह—नापि पूर्वस्येति ॥

(३९९ समाधानवार्तिकम् ॥ ८ ॥)

॥ * ॥ वहुच्पूर्वस्य च ॥ * ॥

(भाष्यम्)

वहुच्पूर्वस्य च पदादिविधावेव, न पदान्तविधाविति ॥

(उद्योतः) भाष्ये—वहुच्पूर्वस्य चेति । आद्यवार्तिकारम्भे तत्प्रत्याख्याने च सात्पदाद्योरित्यत्रेदं कार्यमिति गूढ आशयः ॥

न पदान्तविधाविति प्रतिनिर्देशादुत्तरपदत्वे चेत्यस्य वार्तिकस्य ङमुडादिविधौ णत्वादिविधौ चाप्रवृत्तिरिति बोध्यम् । ङमुट्सूत्रस्थभाष्यं त्वेतद्विरोधाद् उभि च पद इति सूत्रभाष्यविरोधाच्च नलोपादि - सुप्त्यन्त इति वार्तिकस्यभाष्यविरोधाच्चैकदेश्युक्तिरिति बोध्यम् । एवं च प्रत्याख्यानप्रकारोऽपि योगविभागस्य क्वाचित्कत्वेन ङमुडादिविषये न । इदमेव ध्वनयितुं प्रत्याख्यातमपि वार्तिकं पुनरक्षरान्तरेणपाठमित्याहुः ॥

(४०० आक्षेपवार्तिकम् ॥ ९ ॥)

॥ * ॥ द्वन्द्वेऽन्त्यस्य ॥ * ॥

(भाष्यम्)

द्वन्द्वेऽन्त्यस्य लुमता लुप्ते प्रत्ययलक्षणं न भवतीति वक्तव्यम् । वाक्त्वक्त्वचम् ॥

(प्रदीपः) द्वन्द्वेऽन्त्यस्येति । उत्तरपदत्वे चेत्यनेनैव सिद्धे नियमार्थमिदम्—अन्त्यस्यैव - इति, मध्यमपदस्यापि पूर्वपदापेक्षयोत्तरपदत्वसंभवात्प्रत्ययलक्षणप्रतिषेधप्रसङ्गात् । मुख्ये तूत्तरपदे संभवति कथं मध्यमस्य ग्रहणं स्यादिति चिन्त्यमेतत् ॥

(उद्योतः) मुख्ये त्विति । उत्तरपदशब्दस्य समासचरमावयवे रूढेरिति भावः ॥ रूढस्यैव ग्रहणमित्येतदन्वाख्यापकं द्वन्द्वे चेति इति तत्त्वम् । प्रत्याख्यानेऽपि न मध्यमस्य प्राप्तिः, मध्यसुबन्तस्यापि स्वादिपरत्वेन विशेषणात् - इति बोध्यम् ॥

(आक्षेपभाष्यम्)

इह—अभूवन्निति प्रत्ययलक्षणेन जुसभावः प्राप्नोति ॥

(४०१ समाधानवार्तिकम् ॥ १० ॥)

॥ * ॥ सिचि जुसोऽप्रसङ्ग आकारप्रकरणात् ॥ * ॥

(भाष्यम्)

सिचि सिज्निमित्तस्य जुसोऽप्रसङ्गः ॥

किं कारणम् ?

'आकारप्रकरणात्' । 'आतः' इत्येतन्नियमार्थं भविष्यति—आत एव च सिज्लुगन्तात्, नान्यस्मात्सिज्लुगन्तादिति ॥

(प्रदीपः) आकारप्रकरणादिति । आकारस्य नियमार्थत्वेन प्रस्तावादित्यर्थः । अथवाऽऽकारे प्रकरणात्—आत इत्यत्र सिचः प्रकृतत्वादित्यर्थः ॥

(उद्योतः) प्रस्तावादिति । आत इत्यस्यारम्भादित्यर्थः ॥ सिच इति । अनेन विधित्वासंभवो दर्शितः ॥

(आक्षेपभाष्यम्)

इह—इति युष्मत्पुत्रो ददाति-इत्यस्मत्पुत्रो ददातीत्यत्र प्रत्ययलक्षणेन युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वान्नावादयः प्राप्नुवन्ति ॥

(प्रदीपः) इति युष्मत्पुत्र इति । पदादुत्तरयोर्युष्मदस्मदोरादेशविधानादितिशब्दप्रयोगः ॥

(समाधाने भाष्यवार्तिकम्)

॥ युष्मदस्मदोः स्थग्रहणात् ॥

(भाष्यम्)

स्थग्रहणं तत्र क्रियते, तत् श्रूयमाणविभक्तिविशेषणं विज्ञास्यते ॥

(प्रदीपः) श्रूयमाणविभक्तिविशेषणमिति । षष्ठीचतुर्थीद्वितीयास्वित्येव सिद्धे स्थग्रहणे सत्ययमर्थो भवति—तासु ये त्ववस्थिते युष्मदस्मदी इति । श्रूयमाणासु चावस्थानं सम्भवति । न तु लुप्तासु, लुप्तस्याधारत्वासंभवात् ॥

(उद्योतः) भाष्ये—श्रूयमाणेति । श्रूयमाणत्वार्थकं विभक्तिविशेषणमित्यर्थः ॥ तद्यथायोपायं दर्शयति—षष्ठीत्यादि ॥

(समाधानबाधकभाष्यम्)

अस्त्यन्यत्स्थग्रहणस्य प्रयोजनम् ॥

किम् ?

सविभक्तिकस्य वान्नावाक्यो यथा स्युरिति ॥

(प्रदीपः) अस्त्यन्यदिति । तिष्ठतिरहानावपि वर्तते ॥ यथा—तपसि स्थितः, तपो न जहातीत्यर्थः । तथाच—समये तिष्ठ सुग्रीव, समयं मा हासीरित्यर्थः । तेन सति स्थग्रहणे तत्सहितयोः कार्यं विज्ञायते ॥ अथवा यथा रथस्थ आनीयतामिति सरथ आनीयते, तथा षष्ठ्यादिसहितयोर्युष्मदस्मदोः कार्यं भवतीति विज्ञायते ॥

(उद्योतः) अथवा यथा रथस्थेति । सशब्दः साहित्यवाचीति भावः ॥

(समाधानसाधकभाष्यम्)

नैतदस्ति प्रयोजनम् । पदस्येति वर्तते । विभक्त्यन्तं च पदम् । तत्राऽन्तरेणापि स्थग्रहणं सविभक्तिकस्यैव भविष्यन्ति ॥

(प्रदीपः) पदस्येति वर्तत इति । केवलयोः पदत्वाभावात्तदवयवं पदं गृह्यत इति भावः ॥

(उद्योतः) तदवयवमिति । बहुव्रीहिः । युष्मदस्मदोरिति तद्घटितसमुदाये लाक्षणिकमिति भावः ॥

(समाधानबाधकभाष्यम्)

भवेदिस्सिद्धम्—यत्र विभक्त्यन्तं पदम् । यत्र तु खलु विभक्ती पदं तत्र न सिध्यति—ग्रामो वां दीयते, जनपदो वां दीयते, ग्रामो नौ दीयते, जनपदो नौ दीयते ॥

(प्रदीपः) यत्र त्विति । अत्र हि ते एव पदे इति तयोरेवादेशप्रसङ्गः ॥

(उद्योतः) मुख्येऽर्थे एव पदसामानाधिकरण्ये संभवति किं लक्षणयेत्याह—अत्र हीति ॥

(समाधानसाधकभाष्यम्)

सर्वग्रहणमपि प्रकृतमनुवर्तते । तेन सविभक्तिकस्यैव भविष्यति ॥

(प्रदीपः) सर्वग्रहणमपीति । अनेकाल्त्वात्सर्वादेशत्वे लब्धे सर्वग्रहणमनुवृत्तं पञ्चम्यन्तं विपरिणम्यमानं सर्वस्य प्रयोगार्हस्य विभक्त्यन्तस्य स्थानित्वमवगमयतीत्यर्थः ॥

(उद्योतः) यद्यपि द्वितीयायां षष्ठ्यां च तयोः पदत्वासंभवेन तत्र लक्षणाया आवश्यकत्वेनान्यत्राप्येकरूपत्वाय लक्षणा युक्ता, तथापि पदस्येत्यस्य मातुपधाया इत्यादाववयवषष्ठीत्वस्य क्लृप्ततया पदावयवयोरित्यर्थ एव स्यादत ईदृशलक्षणालाभः सर्वग्रहणसाध्य एवेत्याह— सर्वग्रहणमिति । अनुदात्तं सर्वमित्यतः ॥

(आक्षेपभाष्यम्)

इह—चक्षुष्कामं याजयांचकार-इति "तिङ्ङतिङः" इति तस्य च निघातः, तस्माच्चानिघातः प्राप्नोति ॥

(प्रदीपः) याजयांचकारेति । परत्वात्तिबादिषु कृतेषु आम इति लुकि प्रत्ययलक्षणेन याजयामित्यस्य तिङन्तत्वमिति पूर्वः पक्षः ॥

(उद्योतः) ननु लावस्थायामेव अन्तरङ्गानपीति न्यायेन लुकि प्रत्ययलक्षणेनापि न तिङन्तत्वमत आह—परत्वादिति ॥

(४०२ समाधानवार्तिकम् ॥ ११ ॥)

॥ * ॥ आमि लिलोपात्तस्य चानिघातस्तस्माच निघातः ॥ * ॥

(भाष्यम्)

आमि लिलोपात्तस्य चानिघातः, तस्माच्च निघातः सिद्धो भविष्यति ॥

(प्रदीपः) आमि लिलोपादिति । नाप्राप्तेषु तिबादिषु लुगारभ्यमाणस्तेषां बाधकः ॥

(उद्योतः) नाप्राप्तेष्विति । अन्तरङ्गानपीति न्यायादित्यपि बोध्यम् ॥

(अङ्गशब्दवाच्यार्थनिरूपणम्)

(४०३ आक्षेपवार्तिकम् ॥ १ ॥)

॥*॥ अङ्गाधिकार इटो विधिप्रतिषेधौ ॥*॥

(भाष्यम्)

अङ्गाधिकारे इटो विधिप्रतिषेधौ न सिध्यतः ॥ जिगमिष, संविवृत्स । अङ्गस्येतीटो विधिप्रतिषेधौ न प्राप्नुतः ॥

(प्रदीपः) अङ्गाधिकार इति । अङ्गस्येति सर्वत्र, तेनाङ्गाधिकारविहितं यत् कार्यं तल्लुमता लुप्ते प्रत्यये न भवतीति सूत्रार्थे दोषोपन्यासः ॥ जिगमिषेति । अतो ह्रेरिति लुकि कृते गमेरिट् परस्मैपदेष्विवतीद न प्राप्नोति ॥ संविवृत्सेति । न वृद्भ्यश्चतुर्भ्य इतीदप्रतिषेधः ॥

(उद्द्योतः) इट्प्रतिषेध इति । अत्र 'न प्राप्नोति' इत्यनुषङ्गः ॥

(आक्षेपे भाष्यवार्तिकम्)

॥ क्रमेर्दीर्घत्वं च ॥

(उद्द्योतः) दीर्घत्वं—क्रमः परस्मैपदेष्विति ॥

(प्रश्नभाष्यम्)

किं च ?

(प्रदीपः) क्रमेरिति कार्यसमीपे श्रूयमाणश्चकारः कार्यमेव समुच्चिनुयादित्यभिप्रायेणाह—किं चेति ॥

(उद्द्योतः) समुच्चिनुयादिति । तच्चासंभवीति शेषः ॥ इत्यभिप्रायेणेति । प्रश्न इत्यर्थः ॥

(एकदेशिसमाधानभाष्यम्)

इटश्च विधिप्रतिषेधौ ॥

(उद्द्योतः) भाष्ये तटस्थः—अभिप्रायानभिज्ञ उत्तरयति—इटश्चेति ॥

(सिद्धान्तिभाष्यम्)

नेत्याह । अदेशेऽयं चः पठितः । क्रमेश्च दीर्घत्वम् । उत्क्राम - संक्रामेति ॥

(प्रदीपः) अदेश इति । कार्यस्य समुचेतव्यस्याभावात्सामर्थ्यात्प्रकृतिसमुच्चय इत्यर्थः ॥

(उद्द्योतः) आचार्य आह—नेत्याहेति । गम इड्विधिः, वृतेस्तत्प्रतिषेधः, क्रमेश्च दीर्घत्वं न सिध्यतीत्यर्थ इति भावः ॥

(अङ्गाधिकारपरत्वदूषणोपसंहारभाष्यम्)

इह किंचिदङ्गाधिकारे लुमता लुप्ते प्रत्ययलक्षणे भवति, किंचिच्चान्यत्र न भवति ॥

(प्रदीपः) किंचिच्चेति । जिनिकित्स्वराः ॥

(उद्द्योतः) अनन्तरोक्तातिव्याप्तेरुपक्रमोक्ताव्याप्तेश्चाङ्गाधिकारपरत्वं न युज्यत इत्युपसंहरति—भाष्ये—इहेति ॥ जिनिकित्स्वरा इति । इदमुपलक्षणं—अददेदातीत्यत्राडुपीति प्रतिषेधस्यापि । वस्तुतः किंचिच्चेत्यत्र किंचित्पदेन रोऽसुपीत्येव । ञ्नित्स्वरविषये सौवर्णां सप्तमीनां तदन्तसप्तमीत्वेन न लुमता तस्मिन्निति न्यासेऽपि वचनस्यावश्यकत्वादिति बोध्यम् ॥

(न्यासान्तरेण दूषणोद्धारः)

(न्यासान्तरसाधकभाष्यम्)

यदि पुनः—

॥ 'न लुमता तस्मिन्' ॥

इत्युच्येत ॥

(प्रदीपः) न लुमता तस्मिन्निति । लुमता यो लुप्तः प्रत्ययस्तस्मिन्यत्कार्यमाश्रमनाश्रं वा तन्न भवतीत्यर्थः । अत्रय इत्यत्र स्वरो न भवति, तद्धितस्यैव कितोऽन्तोदात्तत्वविधानात् । लुकि कृते कार्यिणोऽसत्त्वात् । प्रत्ययलक्षणं हि यदन्यस्य कार्यं तत्प्रत्ययलोपेऽपि भवति, न तु यत्प्रत्ययस्यैव कार्यं तदपि । न हि वचनेनासतः कार्यित्वं शक्यते प्रतिपादयितुम् ॥

(उद्द्योतः) तस्मिन् यत्कार्यमिति । तस्मिन्परतस्तन्निमित्तकं तत्प्रकृतिभूतस्य यत्कार्यमित्यर्थः ॥ कित इत्युदाहरणभूतात्रय इत्यस्योभयपक्षेऽप्यसिद्धेस्तत् परिहरति—अत्रय इत्यत्रेति ॥ यदन्यस्येति । 'प्रत्ययजं' इत्येव सिद्धे लक्षणग्रहणसामर्थ्येन प्रत्ययनिमित्तकमेव, न तु प्रत्ययस्यानिकमित्यर्थादिति भावः ॥ युक्त्यन्तरमप्याह—न हीति । पष्ठ्यर्थस्योच्चारणरूपप्रसङ्गस्य वक्तुमशक्यत्वादिति भावः ॥ अत एव नखनिर्भिन्न इत्यादावैत्वादिकं न । एवमसतः सत्ताऽपि न वचनेन शक्येति बोध्यम्

(आक्षेपभाष्यम्)

अथ "न लुमता तस्मिन्" इत्युच्यमाने किं सिद्धमेतद्भवति—इटो विधिप्रतिषेधौ क्रमेर्दीर्घत्वं च ॥

(समाधानभाष्यम्)

बाढं सिद्धम् । न इटो विधिप्रतिषेधौ परस्मैपदेष्वित्युच्यते ॥

कथं तर्हि ?

सकारादाविति । तद्विशेषणं परस्मैपदग्रहणम् ॥

न खल्वपि क्रमेर्दीर्घत्वं परस्मैपदेष्वित्युच्यते ॥

कथं तर्हि ?

शितीति । तद्विशेषणं परस्मैपदग्रहणम् ॥

(प्रदीपः) तद्विशेषणमिति । विशेषण एवोपक्षीणत्वात्कार्यं प्रति निमित्तभावो नास्तीत्यर्थः ॥

(उद्द्योतः) 'परस्मैपदपरसादेरङ्गस्यनिमित्तस्येट्' इत्यापत्ते न दोष इत्याह—विशेषण एवेति । एवं च लुप्तप्रत्ययनिमित्तकं तत्प्रकृतेस्तत्र कार्यमिति भावः ॥

(४०४ आक्षेपवार्तिकम् ॥ २ ॥)

॥ * ॥ न लुमता तस्मिन्निति चेद्धनिणिङादेशास्तलोपे ॥ * ॥

(भाष्यम्)

न लुमता तस्मिन्निति चेद्धनिणिङादेशास्तलोपे न सिध्यन्ति ॥ अवधि भवता दस्युः । अगायि भवता ग्रामः । अध्यगायि भवताऽनुवाकः । तलोपे कृते 'लुङि' इति हनिणिङादेशा न प्राप्नुवन्ति ॥

(प्रदीपः) हनिणिङादेशा इति । लुका लुङो विषयस्यापहारात् विषयसप्तम्याश्रयणेऽप्यसिद्धिः ॥

(उद्द्योतः) नन्वार्धधातुक इत्यादीनां विषयसप्तमीत्वात् पूर्वमेव तेषां प्रवृत्तेर्न प्रत्ययलक्षणापेक्षेत्यत आह—लुकेति । एवं च विषयत्वनानायावश्यं प्रत्ययलक्षणमाश्रयणीयम् ॥ तच्च न लुमता तस्मिन्निति न्यासे न प्राप्नोतीति भावः ॥

(समाधानभाष्यम्)

नैष दोषः । न लुङीति हनिणिङादेशा उच्यन्ते ॥

किं तर्हि ?

आर्धधातुक इति । तद्विशेषणं लुङ्ग्रहणम् ॥

(प्रदीपः) तद्विशेषणं लुङ्ग्रहणमिति । तेन लुङ्परे चिणि आदेशविधानम् ॥

(उद्द्योतः) लुङ्परे चिणीति । लुङ्परार्धधातुकविषये इत्यर्थ इति भावः ॥

(आक्षेपभाष्यम्)

इह च—सर्वस्तोमः, सर्वपृष्ठः, "सर्वस्य सुपि" इत्याद्युदात्तत्वं न प्राप्नोति ॥

(एकदेशिसमाधानभाष्यम्)

तत्रापि वक्तव्यम् ॥

(उद्द्योतः) भाष्ये-तत्रापीति । न लुमता तस्मिन्निति वक्तव्यमित्यर्थः ॥

(सिद्धान्तिसमाधानभाष्यम्)

न वक्तव्यम् । "न लुमताऽङ्गस्य" इत्येव सिद्धम् ॥

कथम् ?

न लुमता लुप्तेऽङ्गाधिकारः प्रतिनिर्दिश्यते ॥

किं तर्हि ?

योऽसौ लुमता लुप्यते तस्मिन् यदङ्गं तस्य यत्कार्यं तन्न भवति ॥

(प्रदीपः) न लुमतेति । अङ्गस्येत्यस्य स्वरितत्वाप्रतिज्ञानात्तत्र लुमता लुप्ते प्रत्यये यदङ्गं तस्य यत्कार्यं प्रत्ययाश्रयमाङ्गमनाङ्गं वा तन्न भवतीत्यर्थः ॥

(उद्द्योतः) लुप्ते प्रत्यये यदङ्गमिति । लुप्तप्रत्ययनिरूपिताङ्गसंज्ञकस्य यत्कार्यमित्यर्थः । उत्क्रामेत्यादौ तु परस्मैपदनिमित्ताङ्गसंज्ञकस्य न कार्यम् । किंतु शिदादिनिमित्ताङ्गसंज्ञकस्येति न दोषः ॥ संजिगमिषेत्यादौ सनः कार्यं नाङ्गसंज्ञकस्येति न दोषः ॥ किंच परस्मैपदग्रहणस्य तङानाभावोपलक्षणत्वादपि न दोषः ॥ अगायीत्यादौ तु न दोषः, लुङ्निमित्ताङ्गत्ववतश्चिणन्तस्य कार्याभावादिति बोध्यम् ॥

(आक्षेपभाष्यम्)

एवमपि—सर्वस्वरो न सिध्यति ॥

(उद्द्योतः) भाष्ये—एवमपीति । अङ्गाधिकारप्रतिनिर्देशाभावेऽपीत्यर्थः ॥

(समाधानभाष्यम्)

कर्तव्योऽत्र यत्नः ॥ न लुमताङ्गस्य ॥ ६३ ॥

(प्रदीपः) कर्तव्योऽत्रेति । सर्वशब्दार्थं वचनं कर्तव्यम् ॥ ६३ ॥

(उद्द्योतः) वचनं कर्तव्यमिति । 'सौचर्यः सप्तम्यस्तदन्तसप्तम्यः' इत्येतत् ॥ ६३ ॥

(५९ उपधासंज्ञासूत्रम् ॥ १ । १ । ९ आ. ५ सू. ॥)

अलोऽन्त्यात्पूर्व उपधा ॥ १ । १ । ६५ ॥

(अल इत्यस्य पञ्चम्यन्तत्वनिर्णयः)

(आक्षेपभाष्यम्)

किमिदमल्ग्रहणमन्त्यविशेषणम् ?

(प्रदीपः) अलोऽन्त्यात्० ॥ ६५ ॥ किमिदमिति । प्रथमा पञ्चमी वेति सन्देहात्प्रश्नः ॥

(इष्टापत्तिभाष्यम्)

एवं भवितुमर्हति ॥

(प्रदीप.) एवमिति । प्रथमायामभिप्रेतायामसंदेहार्थमलित्येकवचनं वक्तव्यं स्यात् । अन्त्यादिति पञ्चमीसाहचर्याचाल इत्यपि पञ्चम्यन्तमिति भावः ॥

(उद्द्योतः) अलोऽन्त्यात्० ॥ ६५ ॥ असन्देहार्थमिति । अन्त्यात् पूर्वोऽलित्येव वदेदिति भावः ॥

(४०५ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ उपधासंज्ञायामल्ग्रहणमन्त्यनिर्देशश्चेत्संघातप्रतिषेधः ॥ * ॥

(भाष्यम्)

उपधासंज्ञायामल्ग्रहणमन्त्यनिर्देशश्चेत्संघातस्य प्रतिषेधो वक्तव्यः ॥ संघातस्योपधासंज्ञा प्राप्नोति ॥

तत्र को दोषः ?

"शास इदङ्हलोः" शिष्टः, शिष्टवान् । संघातस्येत्वं प्राप्नोति ॥

(प्रदीपः) अल्ग्रहणमिति । निर्दिश्यते=अभिधीयतेऽनेनेति—निर्देशः । यदन्त्यः प्रत्याय्यत इत्यर्थः ॥ संघातप्रतिषेध इति । पूर्वस्याविशेषितत्वात् समुदायावयवसन्निधौ समुदायस्यैव कार्यित्वादेकाज्द्विर्वचन इवेति भावः ॥ अन्त्यविशेषणत्वे वर्णनिर्देशे जातिग्रहणेऽप्यल इत्युपादानसामर्थ्यात् संख्या विवक्ष्यते ॥

(उद्द्योतः) अल्ग्रहणं-अन्त्यनिर्देश इत्यनयोः सामानाधिकरण्यमनुपपन्नमत आह—अभिधीयतेऽनेनेति । अल्ग्रहणमन्त्यप्रत्यायकं चेदित्यर्थः । घञजपः पुंसीति निर्देशशब्दस्य पुंस्त्वम् ॥ प्राप्तिपूर्वकत्वात्प्रतिषेधस्य प्राप्तिमाह—पूर्वस्येति ॥ एकाजिति । यद्यप्यत्र समुदायसंज्ञया नावयवानामनुग्रहः, तथापि कदाचिदविशेषात्सङ्घातस्यापि स्यादित्यनिष्टमात्रापादने भाष्यतात्पर्यमिति बोध्यम् ॥ ननु संज्ञिवदवधिरपि कस्मात् जातिग्रहणप्राप्तसमुदायो न निषिध्यतेऽत आह—अन्त्येति ॥ संख्या विवक्ष्यत इति । ज्ञापकसिद्धस्यासार्वत्रिकत्वादत्रानेका व्यक्तिर्न गृह्यत इति भावः ॥ सङ्ख्याविवक्षा तु उद्देश्यगतत्वादयुक्ता ॥

(प्रथमान्तपक्षाभ्युपगमभाष्यम्)

यदि पुनः 'अलन्त्यात्' इत्युच्यते ॥

(प्रदीपः) यदि पुनरिति । अत्राप्यल्ग्रहणसामर्थ्यात् संख्या विवक्ष्यते, पिबेर्दैन्तत्वप्रतिज्ञानाच्च लिङ्गात् । अल्स-

मुदायस्य संज्ञित्वे गुणस्य प्राप्तिरेव नास्ति, किमदन्तत्वप्रतिज्ञानेन ॥

(उद्द्योतः) पिबेरदन्तत्वेति । अल्समुदायस्य लघुत्वाभावादिति भावः ॥ सूत्रं तु उखादौ चरितार्थम् । कदाचिदिकारस्याप्युपधात्वेन चिन्त्यमिदम् ॥

(प्रथमान्तपक्षे दूषणभाष्यम्)

एवमप्यन्त्योऽविशेषितो भवति ॥

तत्र को दोषः ?

संघातादपि पूर्वस्योपधासंज्ञा प्रसज्येत ॥

तत्र को दोषः ?

"शास इदङ्हलोः" शिष्टः, शिष्टवान् । शकारस्येत्त्वं प्रसज्येत ॥

सूत्रं च भिद्यते ॥

(प्रदीपः) सूत्रं चेति । अलन्त्यादिति पठ्यमान इत्यर्थः ॥

(सिद्धान्तभाष्यम्)

यथान्यासमेवास्तु ॥

(आक्षेपस्मारणभाष्यम्)

ननु चोक्तम् * उपधासंज्ञायामल्ग्रहणमन्त्यनिर्देशश्चेत् संघातप्रतिषेधः * इति ॥

(परिहारभाष्यम्)

नैष दोषः ॥

(समाधाने भाष्यवार्तिकम्)

॥ अन्त्यविज्ञानात्सिद्धम् ॥

(भाष्यम्)

सिद्धमेतत् ॥

कथम् ?

अलोऽन्त्यस्य विधयो भवन्तीत्यन्त्यस्य भविष्यति ॥

(प्रदीपः) अन्त्यविज्ञानादिति । उपधाया इति षष्ठ्यन्त्यमलं नीयत इत्यर्थः ॥

(परिभाषोपक्रमभाष्यम्)

अन्त्यविज्ञानात् सिद्धमिति चेत् । तन्न ॥

किं कारणम् ?

'नानर्थकेऽलोऽन्त्यविधिरनभ्यासविकारे' ॥

अनर्थकेऽलोऽन्त्यविधिर्नेत्येषा परिभाषा कर्तव्या ॥

किमविशेषेण ?

नेत्याह । अनभ्यासविकारे—अभ्यासविकारान् वर्जयित्वा । "भृञामित्" "अर्तिपिपर्त्योश्च" इति ॥

(प्रदीपः) अनभ्यासविकार इति । अभ्यासोऽनर्थकः । शब्दस्य ह्यावृत्तिर्नार्थस्य ॥

(उद्द्योतः) शब्दस्य हीति । एकाज्धातुविषयमिदम् । अनेकाज्सु प्रथमस्यैकाचो द्वित्वेनार्थवत्त्वशङ्कैव नेति बोध्यम् ॥ एवं चोत्तरखण्ड एवार्थवानिति भावः ॥

(प्रयोजनजिज्ञासाभाष्यम्)

कान्येतस्याः परिभाषायाः प्रयोजनानि ?

(परिभाषाप्रयोजने भाष्यवार्तिकम्)

॥ प्रयोजनमव्यक्तानुकरणस्यात इतौ ॥

(भाष्यम्)

अन्त्यस्य प्राप्नोति । अनर्थकेऽलोऽन्त्यविधिर्न भवति-इति न दोषो भवति ॥

(प्रदीपः) अव्यक्तानुकरणस्येति । अव्यक्तानुकरणस्य योऽच्छब्दस्तस्येतौ पररूपमिति सूत्रार्थः ॥

(उद्द्योतः) अव्यक्तानुकरणस्येति । अच्छब्दान्तस्याव्यक्तानुकरणस्येत्यर्थे संपूर्णस्याच्छब्दस्य पररूपानापत्तिरित्यतो वैयधिकरण्यमुक्तम् ॥ अव्यक्तानुकरणं योऽच्छब्द इति तु नार्थः । एकाचो नेति निषेधारम्भादित्यलम् ॥

(प्रयोजननिराकरणभाष्यम्)

नैतदस्ति प्रयोजनम् । आचार्यप्रवृत्तिर्ज्ञापयति—नान्त्यस्य पररूपं भवतीति । यदयम्—"नाम्रेडितस्यान्त्यस्य तु वा" इत्याह ॥

(प्रदीपः) यदयमिति । वाऽऽम्रेडितस्येत्येव वक्तव्यं स्यात् ॥

(उद्द्योतः) ननु विकल्पार्थं तदावश्यकमत आह—वाऽऽम्रेडितस्येति । अन्त्यस्य पूर्वेण नित्ये पररूपे प्राप्ते इति शेषः ॥

(४०६ प्रयोजनवार्तिकम् ॥ २ ॥)

॥ * ॥ घ्वसोरेद्धावभ्यासलोपश्च ॥ * ॥

(भाष्यम्)

घ्वसोरेद्धावभ्यासलोपश्चेत्यन्त्यस्य प्राप्नोति । अनर्थकेऽलोऽन्त्यविधिर्नेति न दोषो भवति ॥

(प्रदीपः) घ्वसोरिति । अनभ्यासविकार इति प्रतिषेधो रूपवत्यादेशे । लोपस्तु नीरूपः । तथा च पस्पशायां लोपागमवर्णविकारज्ञ इति लोपविकारौ भेदेन निर्दिष्टौ ॥

(उद्द्योतः) भेदेन निर्दिष्टाविति । यद्यप्येकदेशविकृतस्येत्यादौ लोपोऽपि विकारपदेनोच्यते, तथापि व्याख्यानादेवात्रेष्टार्थावगतिरिति बोध्यम् ॥

(प्रयोजननिराकरणभाष्यम्)

एतदपि नास्ति प्रयोजनम् । पुनर्लोपवचनसामर्थ्यात्सर्वस्य भविष्यति ॥

(प्रदीपः) पुनर्लोपेति । लोपो यीत्यतो लोपग्रहणेऽनुवर्तमान इति भावः ॥ तत्र घ्वसोरेद्धावभ्यासस्य चेति

वक्तव्यम् । तत्र व्याख्यानादभ्यासस्य लोप एव भविष्यति, न त्वेत्वम् । योगविभागो वा करिष्यते-घ्वसोरेद्धौ । ततः-अभ्यासस्येति । अत्र च लोपोऽनुवर्तिष्यते । तत्र पुनर्लोपवचनात् सर्वापहारार्थादलोऽन्त्यस्येति बाध्यते ॥

(उद्द्योतः) ननु लोपग्रहणाभावे घ्वसोरेद्धावभ्यासस्येत्युक्ते चकाराभावादन्यवचनाच्च प्रकृतासंबन्धे एत्वमेव स्यादत आह—तत्र घ्वसोरित्यादि ॥ ननु चेनानुवृत्तावपि लोपोऽभ्यासस्यैवेत्यत्र नियामकाभावात्पर्यायेण त्रयाणामप्येत्वलोपौ स्यातामत आह—तत्र व्याख्यानादिति । आगन्तूनामन्ते निवेशेनाभ्यासस्य लोपसंनिहितत्वादिति भावः ॥ नन्वभ्यासपदोत्तरश्चकारः स्यान्यन्तरमेव समुच्चिनुयात्, न विधेयान्तरं-इति एत्वमभ्यासस्यापि स्यादतः परिहारान्तरमाह—योगविभागविति ॥ अत्रेति । न त्वेत्वमित्यर्थः । योगविभागसामर्थ्यादिति भावः ॥ सर्वापहारेति । लोप एव, नावशेषः कस्यचित्-इत्यर्थादिति भावः ॥

(निराकरणयुक्त्यन्तरैकदेशिभाष्यम्)

अथवा—शिल्लोपः करिष्यते । स 'शित्सर्वस्य' इति सर्वादेशो भविष्यति ॥

(आक्षेपभाष्यम्)

स तर्हि शकारः कर्तव्यः ॥

(समाधानभाष्यम्)

न कर्तव्यः । क्रियते न्यास एव द्विशकारको निर्देशः-"घ्वसोरेद्धावभ्यासलोपश्च" इति ॥

(प्रदीपः) **द्विशकारको निर्देश इति** । लोपशब्दात् कृदन्तात्संज्ञिनाऽर्थेनार्थवत्त्वाद्विभक्तौ कृतायां शकारः प्रतिनिर्दिश्यते । तस्य चेत्संज्ञायां सर्वादेशो लोपो भवति । इत्संज्ञोपदेशे एव प्रवर्तते । तत्कार्यं तु प्रयोग इत्येष सिद्धान्तः ॥

(उद्द्योतः) ननु लोपश्शब्दस्यासंज्ञात्वेनानर्थक्यात्सुरेव न उत्पत्तौ वा हल्ङ्यादिलोपाद् द्विशकारक इत्यनुपपन्नमत आह—लोपशब्दादिति । पदस्य संयोगान्तत्वाभावादसन्देहाय च झलां जशित्यत्र जश्त्ववत्संयोगान्तलोपसंयोगादिलोपौ नेति बोध्यम् ॥ इत्संज्ञेति । धातुप्रातिपदिकप्रत्ययनिपातागमादेशानां हलन्त्यमितीत्संज्ञायामपि न दोषः । शस्य स्वरूपेणार्थवत्तया प्रातिपदिकत्वात्, कुण्डिनच इव । उपदेश इति तु तत्र नानुवर्तत इति तत्र भाष्ये स्पष्टम् ॥ उपदेश एवेति । अन्तरङ्गत्वादिति भावः ॥ एतेन लोपविधानकाले शित्त्वाभावात्कथं सर्वादेश इत्यपास्तम् ॥ कार्यं त्विति । अनेकाल्शिदित्यादौ समीपेऽप्यवयवत्वारोपेण न दोष इति भावः । एकान्ता अनुबन्धा इति मुख्यपक्षे तु आद्यमेव समाधानमिति बोध्यम् ॥

(प्रयोजने भाष्यवार्तिकम्)

॥ आपि लोपोऽकोऽनचि ॥

(न्यासान्तरत्वशङ्कानिराकरणभाष्यम्)

तिष्ठति सूत्रम्, अन्यथा व्याख्यायते ॥

(प्रदीपः) **तिष्ठति सूत्रमिति** । लक्ष्यलक्षणभावस्याविवक्षितत्वात्तिष्ठत् सूत्रमिति न कृतम् । तत्रायमर्थः—तिष्ठति सूत्रम्-न प्रत्याख्यायते, तत्तु अन्यथा व्याख्यायते । तत्रानचीत्यनेन हलीत्यस्यार्थ आख्यातः । आप्यक इत्यनुवृत्तिर्दर्शिता ॥

(उद्द्योतः) भाष्ये—अन्यथाव्याख्यायत इति । न तु तत्प्रत्याख्याय तत्स्थाने वचनान्तरं पठितमिति भ्रमितव्यमिति भावः ॥

(वार्तिकव्याख्याभाष्यम्)

आपि हलि लोप इत्यन्तस्य प्राप्नोति । अनर्थकेऽलोऽन्त्यविधिर्नेति न दोषो भवति ॥

(उद्द्योतः) इत्यन्तस्येति । एवं च तेन दलोपे 'आभ्यां' इत्यसिद्धिरिति भावः ॥

(प्रयोजननिराकरणभाष्यम्)

एतदपि नास्ति प्रयोजनम् । अन एव लोपं वक्ष्यामि ॥

(प्रदीपः) **अन एवेति** । अनाप्यक इति सामान्येनानादेशं विधाय हलादौ तु तस्यैव लोपो विधास्यत इत्यर्थः ॥ येन नाव्यवधानमिति त्यदाद्यत्वे न व्यवधानमाश्रीयते ॥

(उद्द्योतः) ननु मस्यानिकत्यदाद्यत्वेन व्यवधानात्कथं हलादिविभक्तिपरतेत्यत आह—येन नेति । आप्परत्वेनेदमो विशेषणात्वेऽपि बोध्यम् ॥ इदं 'इदो लोपः' इत्यर्थेऽप्यावश्यकम् । एवं च नलोपे द्वयोरकारयोः पररूपे सुपि चेति दीर्घे सिद्धं—आभ्यामिति ।

(गौरवाक्षेपभाष्यम्)

तदनो ग्रहणं कर्तव्यम् ॥

(गौरवनिराकरणभाष्यम्)

प्रकृतमनुवर्तते ॥

क्व प्रकृतम् ?

"अनाप्यकः" इति ॥

(अनुवृत्तिबाधकभाष्यम्)

तद्वै प्रथमानिर्दिष्टम्, षष्ठीनिर्दिष्टेन चेहार्थः ॥

(अनुवृत्तिसाधकभाष्यम्)

'हलि' इत्येषा सप्तमी 'अन्' इति प्रथमायां षष्ठीं प्रकल्पयिष्यति-"तस्मिन्निति निर्दिष्टे पूर्वस्य" इति ॥

(प्रयोजने भाष्यवार्तिकम्)

॥ अत्र लोपोऽभ्यासस्य ॥

(भाष्यम्)

अन्त्यस्य प्राप्नोति । 'नानर्थकेऽलोऽन्त्यविधिः' इति न दोषो भवति ॥

(प्रयोजननिराकरणभाष्यम्)

एतदपि नास्ति प्रयोजनम् । 'अत्र' ग्रहणसामर्थ्यात्सर्वस्य भविष्यति ॥

(प्रदीपः) **अत्रग्रहणसामर्थ्यादिति** । मीमाश्वीनामधिकारादेव सिद्धेऽत्रग्रहणादयमर्थ आश्रीयते—योऽभ्यासत्वेन निर्ज्ञातस्तस्य समग्रस्य लोपो न त्वलोऽन्त्यस्येति ॥

(उद्द्योतः) अत्रग्रहणादिति । अत्रशब्देन पुनः सनः

परामर्शात्सनि योऽभ्यासस्ताक्रान्तस्तस्य सर्वस्य लोप इत्यर्थ इति भावः ॥

(प्रयोजनसाधकभाष्यम्)

अस्त्यन्यदत्रग्रहणस्य प्रयोजनम् ॥

किम् ?

सन्नधिकारोऽपेक्ष्यते । इह मा भूत्—दधौ, ददौ ॥

(प्रयोजनबाधकभाष्यम्)

अन्तरेणाप्यत्रग्रहणं सन्नधिकारमपेक्षिष्यामहे ॥

(प्रयोजनसाधकभाष्यम्)

सस्तर्हि सकारादिरपेक्ष्यते—सनि सकारादाविति । इह मा भूत्—जिज्ञापयिषतीति ॥

(प्रयोजनबाधकभाष्यम्)

अन्तरेणाप्यत्रग्रहणं सनं सकारादिमपेक्षिष्यामहे ॥

(प्रयोजनसाधकभाष्यम्)

प्रकृतयस्तर्ह्यपेक्ष्यन्ते—एतासां प्रकृतीनां लोपो यथा स्यात् । इह मा भूत्—पियक्षति, पिपक्षति ॥

(प्रयोजनबाधकभाष्यम्)

अन्तरेणाप्यत्रग्रहणमेताः प्रकृतीरपेक्षिष्यामहे ॥

(प्रयोजनसाधकभाष्यम्)

विषयस्तर्ह्यपेक्ष्यते—"मुचोऽकर्मकस्य गुणो वा" इति । इह मा भूत्—मुमुक्षति गामिति ॥

(प्रयोजनबाधकभाष्यम्)

अन्तरेणाप्यत्रग्रहणमेतं विषयमपेक्षिष्यामहे ॥

कथम् ?

अकर्मकस्येत्युच्यते, तेन यत्रैवायं मुचिरकर्मकस्तत्रैव भविष्यति ॥ तस्मान्नार्थोऽनया परिभाषया—'नानर्थकेऽलोऽन्त्यविधिः' इति ॥

(उद्योतः) भाष्ये—विषयमपेक्षिष्यामह इति । मुचोऽकर्मकस्य गुण इत्यनुवर्तनीयम् । यत्र मुचोऽकर्मकस्य गुणस्तत्राभ्यासस्य लोप इत्यर्थः । अकर्मकग्रहणमात्रानुवृत्तौ तु मुमुक्षते वत्सः स्वयमेवेत्यत्रापि स्यादिति भावः ॥ विभाषा भवदिति वार्तिकेऽपि 'वस्य' इत्येव सिद्धे 'अवस्य' इत्युच्चारणसामर्थ्याद् अलोऽन्त्यस्येति न प्रवर्तते इति प्रत्याख्याता परिभाषा ॥

(न्यासान्तरे भाष्यवार्तिकम् ॥)

* ॥ अलोऽन्त्यात् पूर्वोऽलुपधेति वा ॥ *

(भाष्यम्)

अथवा ऽयकमेवैतत् पठितव्यम्—अलोऽन्त्यात्पूर्वोऽलुपधासंज्ञो भवतीति ॥

(उद्योतः) एवं च अन्त्यविज्ञानात्सिद्धमित्यस्य सिततत्वाद्वार्तिके वाशब्दप्रयोगस्तदाह—अथवा ऽयकमेवेति ॥

(आक्षेपभाष्यम्)

तत्तर्हि वक्तव्यम् ?

(परिहारभाष्यम्)

न वक्तव्यम् ॥

(समाधाने भाष्यवार्तिकम् ॥)

* ॥ अवचनाल्लोकविज्ञानात् सिद्धम् ॥ *

(भाष्यम्)

अन्तरेणापि वचनं लोकविज्ञानात् सिद्धमेतत् । तद्यथा—लोके—अमीषां ब्राह्मणानामन्त्यात्पूर्व आनीयतामित्युक्ते यथाजातीयकोऽन्त्यस्तथाजातीयकोऽन्त्यात्पूर्व आनीयते ॥ अलोऽन्त्यात्पूर्व उपधा ॥ ६५ ॥

(प्रदीपः) यथाजातीयकोऽन्त्य इति । एतच्च ब्रुवता पञ्चमीपक्ष एवाश्रितः । षष्ठीप्रथमयोरपि न दोषः । षष्ठीपक्षे निर्धारणे षष्ठी । निर्धारणं च तुल्यजातीयस्य भवतीति अलां मध्ये योऽन्त्योऽल् तस्मात् पूर्वं उपधासंज्ञ इत्यलेवोक्तान्न्यायात्प्रतीयते ॥ प्रथमाबहुवचनपक्षेऽप्ययमर्थः—अन्त्यात् पूर्वोऽलुपधासंज्ञ इति । अल इति जातौ बहुवचनम्, अवधिमत्तुल्यजातीयकश्चावधिरिति अलोऽन्त्यादिति विज्ञायते ॥ ६५ ॥

(उद्योतः) एवञ्चेति । अवधिनाऽवधिमतो निर्णयं ब्रुवता -इत्यर्थः । संयोगोपधेत्यादिव्यवहारास्तु गौणा इति भावः ॥ षष्ठीप्रथमयोरपीति । दृष्टान्तेऽमीषां ब्राह्मणानामित्युपाददता भगवता सूचितमिदम् ॥ उक्तान्न्यायादिति । भाष्योक्तादित्यर्थः ॥ जातौ बहुवचनमिति । भाष्यकृता जात्याख्यायामिति सूत्रप्रत्याख्यानादिदं चिन्त्यम् ॥ ६५ ॥

(६०-६१ परिभाषासूत्रे ॥ १ । १ । ९ आ. ६-७ सू०)

तस्मिन्निति निर्दिष्टे पूर्वस्य ॥ १।१।६६ ॥

तस्मादित्युत्तरस्य ॥ १ । १ । ६७ ॥

(उदाहरणनिरूपणम्)

(आक्षेपभाष्यम्)

किमुदाहरणम् ?

(प्रदीपः) तस्मिन्निति० ॥६६-६७॥ किमुदाहरणमिति । इतिकरणस्य गौरित्ययमाहेत्यादौ स्वरूपपदार्थकत्वेन व्यवस्थापकत्वदर्शनात्प्रश्नः ॥

(उद्योतः) तस्मिन्निति० ॥ ६६-६७ ॥ स्वरूपपदार्थकत्वेनेति । स्वरूपस्य तत्र विशेष्यत्वादिति भावः ॥ प्रश्न इति । तस्मिन्नपि चेत्यत्रैव वा-उतान्यत्रापीति प्रश्न इति भावः ॥

(समाधानभाष्यम्)

इह तावत्—"तस्मिन्निति निर्दिष्टे पूर्वस्य" इति "इको यणचि", दध्यत्र-मध्वत्र ॥

इह—"तस्मादित्युत्तरस्य" इति "द्व्यन्तरुपसर्गे-

भ्योऽप ईत्", द्वीपम्-अन्तरीपम्-समीपम् ॥

(प्रदीपः) **दृष्यत्रेति** । यदि **तस्मिन्नणि चेति तस्माच्छस** इति चात्रैवैते परिभाषे उपास्थास्येतां तदा तत्रैव पूर्वग्रहणमुत्तरग्रहणं चाऽकरिष्येतामिति भावः ॥ अत्रं व्यवच्छेद्यमस्ति— 'यौष्माकीण अस्मभ्यं देहि''आस्माकीन युष्मभ्यं दीयताम्' इति खञः परयोर्युष्मदस्मदोरादेशौ न भवतः ॥ 'वृक्षान्' इत्यत्र च पूर्वसवर्णदीर्घभूताच्छसः पूर्वस्य षकारस्य नत्वं न भवति ॥ अथ शस इति षष्ठीति व्याख्यानात् षकारस्य न भवतीत्युच्यते। एवमपि 'उचरत आनुपलभते' इत्यादौ पूर्वसवर्णदीर्घात्पूर्वस्य शसो नत्वं व्यवच्छेद्यमेव ॥

(उद्योतः) **तत्रैव पूर्वेति** । ननु **तस्मान्नुडचि तस्मान्नुड्द्विहलः तस्माच्छस** इति सूत्रत्रये उत्तरग्रहणे विपरीतं गौरवमिति चेन्न । यतो द्विहलो नुड्विधायके नास्योपयोगः, तत्राङ्गाधिकारेण लिण्निमित्ताङ्गसंबन्धिदीर्घात्पूर्वस्य प्रत्यासत्त्या तदङ्गसंबन्धिनोऽसंभवेन फलाभावात् ॥ एवं **तस्मान् नुडचीत्यत्रापि न दोषः,** उत्तरपदाधिकारेण प्रत्यासत्त्या नञ्रूपपूर्वपदनिरूपितोत्तरपदस्यैव तेन नुड्विधानात् इति भावः ॥ **तस्मिन्निति** परामृष्टखञव्यवधानाय संबुद्धन्तमुदाहरति—**यौष्माकीणेति** ॥ **षकारस्येति** । **तस्मादित्येतत्सात्र्चर्याच्छस** इति पञ्चमी । शसा च सामानाधिकरण्यं शसवयवे लक्षणयेति भावः ॥ मुख्यार्थे सामानाधिकरण्यासंभवात् स्थान्याकाङ्क्षासत्त्वाच्च-अवयवषष्ठीत्याशङ्कते—**अथेति** ॥ **शस इति स्थानषष्ठ्यपाठः** । **इति षष्ठीत्येव** पाठः ॥ **आन्** इति अशब्दस्य शसि रूपम् ॥

(समाधानबाधकभाष्यम्)

अन्यथाजातीयकेन शब्देन निर्देशः क्रियते, अन्यथाजातीयक उदाह्रियते ॥

(प्रदीपः) **अन्यथाजातीयकेनेति** । इतिकरणात् स्वरूपग्रहणेनैव भाव्यमिति भावः ॥ थाला प्रकारमात्रमभिधीयत इति तद्वतोऽभिधानाय जातीयर् प्रत्ययः ॥ लौकिके प्रयोगे लाघवानादरप्रदर्शनाय प्रत्ययद्वयप्रयोगः, केवलेनापि जातीयरा प्रकारवान् गम्यत एव ॥

(उद्योतः) **इतिकरणादिति** । लोकेऽर्थप्रधानस्य पदार्थविपर्यासकेतिना शब्दप्रधानत्वदर्शनादिति भावः ॥ नन्वेकार्थकप्रत्ययद्वयोपादानं व्यर्थमत आह—**थालेति** । एवं च **शब्देनेत्यनेन** सामानाधिकरण्यानुपपत्तिः, जातीयस्तु तद्वति स्वभावादिति भावः ॥ नन्वेवं जातीय एव प्रयुज्यतां किं थालेत्यत आह—**लौकिके इति** । उभयोः प्रकारवद्वृत्तित्वेऽप्येवं वक्तुं शक्यमिति उक्तयक्तो वृथा । अत एव कस्य प्रयोगः - इति **चिन्त्यम्** ॥

(प्रत्याक्षेपभाष्यम्)

किं तर्ह्युदाहरणम् ?

(प्रत्याक्षेपसमाधानभाष्यम्)

इह तावत्—"तस्मिन्निति निर्दिष्टे पूर्वस्य" इति "तस्मिन्नणि च युष्माकास्माकौ" इति ॥

"तस्मादित्युत्तरस्य" इति "तस्माच्छसो नः पुंसि" इति ॥

(सिद्धान्तिभाष्यम्)

इदं चाप्युदाहरणम्—"इको यणचि". "द्व्यन्तरुपसर्गेभ्योऽप ईत्" इति ॥

कथम् ?

सर्वनाम्नाऽयं निर्देशः क्रियते । सर्वनाम च सामान्यवाची । तत्र सामान्ये निर्दिष्टे विशेषा अप्युदाहरणानि भवन्ति ॥

(प्रदीपः) **इदं चाऽपीति** । सिद्धान्तवादी ॥ इतिकरणोऽत्रार्थनिर्देशार्थ एव, स्वं रूपमिति वचनात्स्वरूपग्रहणे प्राप्ते ॥ **सर्वनाम्नोऽयमिति** । सूत्रान्तरोपात्तस्य **तस्मिन्नित्यस्य तस्मादित्यस्य** च नैतदनुकरणम् । किं तर्हि? सर्वनाम्ना निर्देश इत्यर्थः । तेन यत्र सप्तम्यर्थनिर्देशः पञ्चम्यर्थनिर्देशश्च तत्रोभयोरुपस्थानम् ॥ **विशेषा अपीति** । अपिः संभावनायाम्, न समुच्चये । न हि विशेषपरित्यागेनेह शास्त्रे सामान्यमस्ति, यदुदाहरणं स्यात् । तस्मात्सर्वे विशेषा इहोदाहरणमित्यर्थः, सामान्यस्य सर्वविशेषेषु भावात् ॥

(उद्योतः) ननु दूषितस्य कथमुदाहरणत्वेन दानमत आह—**सिद्धान्तेति** ॥ **अर्थनिर्देशार्थ एवेति** । अन्यथा तस्मिन्निति शब्दे, अचीत्यादिशब्देषु वाऽव्यवहितेषु इत्यर्थः स्यादिति भावः ॥ **नैतदनुकरणमिति** । प्रागुक्तयुक्तेरिति भावः ॥ **सर्वनाम्नेति** । सप्तम्यन्तार्थकसर्वनाम्नेत्यर्थः ॥ सप्तमी त्वस्य सप्तम्यन्तार्थकत्वबोधनायानुवादिकेति भावः ॥ इतिशब्दलभ्यमर्थमाह—**यत्र सप्तम्यर्थेति** । सप्तम्यर्थबोध इत्यार्थः ॥ अत एव **तस्मान्नुडचीत्यादौ** न प्रवृत्तिः, अचि इत्यस्य षष्ठ्यर्थत्वादिति भावः । **सप्तमीपञ्चम्यर्थौ** अधिकरणावधी ॥ अयं पदोपस्थितिपक्षेऽर्थो दर्शितः । पक्षान्तरेऽपि सप्तम्यन्तार्थेऽव्यवहिते सतीत्यर्थो बोध्यः ॥ भाष्ये-**सामान्यवाचीति** । बुद्धिस्थत्वेनैव तदादीनां बोधकतेति भावः ॥ **सामान्यम्**—अनिर्धारितविशेषम् । **तस्मिन्नणिचेत्यादेरपि** सप्तमीपञ्चमीविशेषत्वादित्याशयः ॥ **सामान्यस्य-बुद्धिस्थत्वस्य सर्वविशेषेषु भावात्**—सत्त्वादित्यर्थः ॥

(आक्षेपभाष्यम्)

किं पुनः सामान्यम्, को विशेषः ?

(प्रदीपः) **किं पुनरिति** । सामान्यविशेषभावस्यानवस्थानात्प्रश्नः । कदाचिद्दूराद्गोत्वमात्रग्रहणं पश्चात् कृष्णादिविशेषावगमः, कदाचित् पूर्वं कृष्णादेर्ग्रहणं पश्चाद्गोत्वादेः ॥

(उद्योतः) उक्तमर्थमजानानस्य चोद्यमित्यभिप्रायेणाह—**सामान्येति** । **तस्मिन्नितीत्यस्य तस्मिन्नणि** चेत्यादिः कथं विशेषः? तस्यापि खञादिनिरूपितसामान्यत्वादिति, अचीत्यस्याप्यकाराद्यपेक्षया सामान्यत्वादिति च प्रश्न इत्यपि बोध्यम् ॥ ननु कथमनवस्थितिः? पूर्वावगतं **सामान्यम्**, पश्चादवगतो **विशेषः**—इति व्यवस्थासंभवादत आह—**कदाचिदिति** । परिच्छेद्यपरिच्छेदकभावोऽनियत इत्यर्थः ॥ एवं प्रकृतेऽप्यचीत्यादीनां बुद्धिस्थत्वेन परिच्छेदात् बुद्धिस्थस्यापि तैः परिच्छेदादनिर्णय इति भावः ॥

(समाधानभाष्यम्)

गौः सामान्यम् । कृष्णो विशेषः ॥

(प्रदीपः) **गौः सामान्यमिति** । यद्विशेष्यं प्रधानं

तत्सामान्यम् । यत्तु विशेषणत्वेन परोपकारितया निर्दिश्यते स विशेष इति तात्पर्यम् । इहापि तस्मिन्नित्यनेन सप्तम्यर्थमात्रं सामान्यं निर्दिष्टम् । अचि-हलीत्यादयस्तु विशेषाः ॥

(उद्द्योतः) विशेष्यं प्रधानमिति । परिच्छेद्यमित्यर्थः ॥ परोपकारितया-परिच्छेदकत्वेन । एवं प्रकृतेऽपि तस्मिन्नित्यर्थस्य परिच्छेद्यत्वेन विवक्षणात्सामान्यत्वम्, अचीत्यादीनां परिच्छेदकत्व-विवक्षणाद्विशेषत्वमिति भावः ॥ तदाह—इहापीति । अयं भावः—सप्तम्यन्तार्थे इत्युक्ते कस्मिन्नित्याकाङ्क्षोदयात् 'अचि' इत्याद्यर्थस्य परि-च्छेदकत्वाद्विशेषत्वमेवेति ॥

(आक्षेपभाष्यम्)

न तर्हीदानीं कृष्णः सामान्यम्, गौर्विशेषो भवति ?

(समाधानभाष्यम्)

भवति च ॥

(आक्षेपभाष्यम्)

यदि तर्हि सामान्यमपि विशेषः, विशेषोऽपि सामान्यम्, सामान्यविशेषौ न प्रकल्पेते ॥

(समाधानभाष्यम्)

प्रकल्पेते च ॥

कथम् ?

विवक्षातः ।

यदाऽस्य गौः सामान्येन विवक्षितो भवति कृष्णो विशेषत्वेन, तदा गौः सामान्यम्, कृष्णो विशेषः ॥ यदाऽस्य कृष्णः सामान्येन विवक्षितो भवति गौर्विशेषत्वेन विवक्षितः, तदा कृष्णः सामान्यम्, गौर्विशेषः ॥

(दृष्टान्तान्तरभाष्यम्)

अपर आह—'प्रकल्पेते च' ॥

कथम् ?

पितापुत्रवत् । तद्यथा—स एव कंचित्प्रति पिता भवति, कंचित्प्रति पुत्रो भवति । एवमिहापि स एव कंचित्प्रति सामान्यं, कंचित्प्रति विशेषः ॥

एते खल्वपि नैर्देशिकानां वार्त्ततरका भवन्ति, ये सर्वनाम्ना निर्देशाः क्रियन्ते । एतैर्हि बहुतरकं व्याप्यते ॥

(प्रदीपः) पितापुत्रवदिति । जन्यजनकशक्तिद्वययोगवदेकस्यैव विशेषणविशेष्यशक्तिद्वययोगात्कदाचित्कचित्काचिच्छ-क्तिराश्रीयते ॥ 'सप्तमीनिर्दिष्टे पूर्वस्य' इत्येव कस्मान्नोच्यत इत्याह—एते खल्वपीति । नैर्देशिकानां=निर्देशप्रयोज-नानां मध्ये । वार्त्ततरकाः=युक्ततरका इत्यर्थः । भाष्यकारवच-नप्रामाण्यादत्र तरप्प्रत्ययः । तमपा त्वत्र भाव्यम् ॥ एतैर्हीति । यदि हि सप्तमीनिर्दिष्ट इत्युच्यते, तदा सप्तमीशब्देन यो निर्दिष्ट इति प्रतीयेतेति भावः ॥

(उद्द्योतः) तदेवं पर्यायेण सामान्यविशेषभावमुपपाद्य द्विती-यविधया कृतं प्रश्नं समाधातुं यौगपद्येनापि तमुपपादयितुमाह—भाष्ये—पितेत्यादि । यथा 'पराशरात्मजं वन्दे शुकतातं तपो-निधिम्' इत्यत्र, तथा राजपुरुषाश्व इत्यत्र पुरुषो राजापेक्षया विशेष्यः, अश्वापेक्षया विशेषणम् । एवं प्रकृते सप्तम्यादिनिरूपितसामान्यस्यापि तस्मिन्नणिचेत्यस्य तस्मिन्निन्नितीत्येतत्प्रति विशेषत्वमिति भावः ॥ इत्याहेति । इत्यत आहेत्यर्थः ॥ निर्देशप्रयोजनानामिति ॥ बोधप्रयोजनकानां शब्दानां मध्ये—इत्यर्थः ॥ बहुवचनविभज्योपपद-त्वादाह—भाष्यकारेति ॥ परे तु नैर्देशिकानां मध्येऽन्येभ्यः शब्देभ्य इत्यध्याहृत्य विभज्योपपदेऽत्र तरप् । अत एव न सत्स्वपि बहूनां प्रकर्षे तरपा भवितव्यमिति तरप्सूत्रस्थभाष्येणाविरोध इत्याहुः ॥ सप्तमीशब्देनेति । तथा च सप्तम्यां जनेर्डः इत्यादा-वेवेदमुपतिष्ठेतेति भावः ॥ किंच यत्र सप्तम्यन्तनिर्देश इत्यर्थे नेह धशि कृतीत्यादौ दोषः, तत्र कृतीति सप्तमीनिर्देशसत्त्वात्; परंतु षष्ठ्यर्थे स इति भावः ॥ 'सप्तमीति निर्दिष्टे' इति सूत्रकरणेऽपि तद-र्थेऽव्यादिनिर्देश इत्यर्थे स एव दोषः ॥

(आक्षेपभाष्यम्)

अथ किमर्थमुपसर्गेण निर्देशः क्रियते ?

(प्रदीपः) किमर्थमिति । किमर्थमुपसर्गयुक्तस्य धातोर्नि-र्देशः क्रियते, 'तस्मिन्निति पूर्वस्य' इति कस्मान्नोच्यत इति प्रश्नः । न पुनः 'दिष्टे' इत्येवोच्यतामिति प्रश्नः, केवलस्य दिशेर्दानार्थ-त्वादिहानुपयोगात् ॥

(उद्द्योतः) यथाश्रुतमेव कस्मान्न गृह्यत इत्यत आह—न पुनरिति । अत एव किमर्थमुपसर्गनिर्देशो न दिष्ट इत्येवोच्ये-तेति नोक्तम् ॥

(समाधानभाष्यम्)

शब्दे सप्तम्या निर्दिष्टे पूर्वस्य कार्यं यथा स्यात् । अर्थे मा भूत्—जनपदे अतिशायने-इति ॥

(प्रदीपः) शब्द इति । अन्तरेणाऽपि निर्दिष्टग्रहणं 'तस्मिन्निति पूर्वस्य' इति निर्दिष्टत्वे लब्धे पुनर्निर्दिष्टशब्द उपा-दीयमानो बहिर्भावं गमयति । शब्दाच्च बहिर्भूतः शब्द एव भव-तीति ॥ जनपद इति । तत्रायमर्थः स्यात्—जनपदवाचिनि शब्दे परतश्चातुरर्थिकस्य लुप् भवतीति ॥

(उद्द्योतः) अन्तरेणापीति । साकाङ्क्षतया 'उच्चारिते' इति पदाध्याहारादिति भावः ॥ पुनर्निर्दिष्टेति । एवं च सप्तम्यन्तार्थे बहिर्भूते उपश्लिष्टस्य पूर्वस्येत्यर्थः ॥ बहिर्भावस्य चावध्यपेक्षत्वादवधेश्च संनिधानात्तस्यैव ग्रहीतुमुचितत्वेन तस्य च शब्दात्मकत्वादवधिमानपि शब्द एवेति शब्दे सप्तमीनिर्दिष्टे पूर्वस्येति लभ्यत इति भावः ॥ ननु प्रत्ययस्य अर्थेन पौर्वापर्यासंभवात् कथं जनपदे इत्यत्रास्योपस्थानमत आह—तत्रायमर्थः स्यादिति । लक्षणा स्यादिति भावः ॥ निर्दि-ष्टग्रहणे तु यत्र मुख्यया वृत्त्या शब्दतात्पर्यको निर्देशस्तत्रास्योप-स्थानमिति न दोष इति तात्पर्यम् ॥

(आक्षेपभाष्यम्)

किं गतमेतदुपसर्गेण, आहोस्विच्छब्दाधिक्यादर्थाधिक्यम् ॥

(समाधानभाष्यम्)

गतमित्याह ॥

कथम् ?

निरयं बहिर्भावे वर्तते । तद्यथा—निष्क्रान्तो देशात्-निर्देशः, बहिर्देश इति गम्यते । शब्दश्च शब्दाद्बहिर्भूतः । अर्थः-अबहिर्भूतः ॥

(आक्षेपभाष्यम्)

अथ निर्दिष्टग्रहणं किमर्थम् ?

(प्रदीपः) अथेति । ननु प्रयोजनस्योक्तत्वात् पुनः प्रश्नानुपपत्तिः । अयं भावः—जनपदे लुबित्यत्रार्थेन पौर्वापर्यासम्भवात् 'जनपदे य उत्पन्नः प्रत्ययस्तस्य लुप् भवति, तथा अतिशायने वर्तमानात्तमबादयः' इति अर्थनिर्देशेषूपस्थानं न भविष्यति । यदि चैतत्प्रयोजनम्, तदा तस्मिन्निति शब्दे पूर्वस्येति वक्तव्यम् ॥

(उद्द्योतः) अर्थेन पौर्वेति । तद्वाचकशब्दलक्षणायां च न मानमिति भावः ॥ तत्रार्थनिर्देशे च व्याख्यानमेव शरणम् । एवञ्च अथ किमर्थमित्यादिपूर्वपक्षसिद्धान्तावेकदेशिनोरिति बोध्यम् ॥ किं चार्थनिर्देशे 'जनपदे यः प्रत्यय इत्यन्वये नियमप्रसङ्गाभावान्नियमफलका परिभाषा नोपतिष्ठते' इत्यपि बोध्यम् ॥

(३७५ समाधानवार्तिकम् ॥ १ ॥)

॥ * ॥ निर्दिष्टग्रहणमानन्तर्यार्थम् ॥ * ॥

(भाष्यम्)

निर्दिष्टग्रहणं क्रियते । आनन्तर्यमात्रे कार्यं यथा स्यात्—"इको यणचि", दध्यत्र-मध्वत्र । इह मा भूत्—समिधौ-समिधः, दृषदौ-दृषदः ॥

(प्रदीपः) निर्दिष्टग्रहणमिति । पूर्वोक्तप्रयोजनाभावादिति भावः । निःशब्दो नैरन्तर्ये वर्तते, दिशिश्चोच्चारणक्रियः । तेन निरन्तरोच्चारिते कार्यं-इति लभ्यते ॥ समिधाविति । ननु संहितायामित्युच्यते । न च व्यवहितयोः संहिताऽस्ति । अचीति चाधिकरणमौपश्लेषिकं निर्दिष्टम् । न च व्यवहित उपश्लिष्टो भवति ॥ नैष दोषः । वर्णानां परः संनिकर्षः संहिता । सा चात्रास्ति । अचीति सत्सप्तमी विज्ञायेत । व्यवहितेऽपि पूर्वशब्दो वर्तते-इति यत्र विषये यथाभूत इक् संभवति अनन्तरो व्यवहितो वा तत्र तथाभूतस्यैव यणादेशः स्यात् ॥

(उद्द्योतः) भाष्ये—आनन्तर्यमात्रे इति । .. तु व्यवधाने इत्यर्थः ॥ ननु संहितायामिति । निमित्तस्थानिनोरन्येनाव्यवधानं-संहितेति भावः ॥ उपश्लिष्ट इति । उप-समीपे श्लिष्टः, अत्यन्तसमीप इति हि तदर्थः ॥ नैष दोष इति । वर्णशून्यकालाभावः-संहितेति भावः ॥ सत्सप्तमीति । औपश्लेषिकाधिकरणत्वस्य व्यवहिते बाधात्, सत्ता तु व्यवहितेऽपीति भावः । एवं च निर्दिष्टग्रहणमौपश्लेषिकाधिकरणसप्तम्यां तात्पर्यग्राहकमिति तात्पर्यम् ॥ वस्तुत उपश्लेषोऽप्यल्पव्यवहितेऽस्त्येव, किञ्चिद्दूरस्थितेऽपि वृक्षमूले तिष्ठतीति कटव्यवधानेऽपि क..शेत इति च व्यवहारात् ॥ ननु व्यवहिते इकोऽचः पूर्वत्वाभावेनाप्राप्ते निर्दिष्टग्रहणं व्यर्थमत आह—व्यवहितेऽपीति । मथुरायाः पूर्वं पाटलिपुत्रमित्यादिव्यवहारादिति भावः ॥ यत्र विषये इति । लक्ष्यभेदेन लक्षणभेद इति भावः ॥ वस्तुतः संहिताधिकारो न कर्तव्य इत्यभिप्रायमिदं भाष्यम् ॥ संहिताधिकारप्रत्याख्यानं च तत्सूत्रे भाष्ये स्पष्टम् ॥

(सूत्रस्य नियमार्थत्वम्)

(आक्षेपभाष्यम्)

किमर्थं पुनरिदमुच्यते ?

(प्रदीपः) किमर्थमिति । किं नियमार्थमथ षष्ठीप्रक्लृप्त्यर्थमिति प्रश्नः ॥

(उद्द्योतः) किमुदाहरणमित्यादिना सूत्रप्रयोजनस्योक्तत्वात्प्रश्नानुपपत्तिरत आह—किं नियमार्थमित्यादि ॥

(३७६ समाधानवार्तिकम् ॥ १ ॥)

॥ * ॥ तस्मिँस्तस्मादिति पूर्वोत्तरयोर्योगाविशेषान्नियमार्थं वचनं दध्युदकं पचत्योदनम् ॥ * ॥

(भाष्यम्)

तस्मिंस्तस्मादिति पूर्वोत्तरयोर्योगयोरविशेषान्नियमार्थोऽयमारम्भः । ग्रामे देवदत्तः, पूर्वः पर इति संदेहः । ग्रामाद्देवदत्तः, पूर्वः पर इति संदेहः । एवमिहापि—"इको यणचि", दध्युदकम्-पचत्योदनम् । उभाविकौ, उभावचौ । अचि पूर्वस्य-अचि परस्येति संदेहः ॥ "तिङ्ङतिङः" इति । अतिङः पूर्वस्य, परस्येति संदेहः ॥

इष्यते चात्राचि पूर्वस्य स्यात्, अतिङः परस्येति । तच्चान्तरेण यत्नं न सिध्यतीति नियमार्थं वचनम् ॥ एवमर्थमिदमुच्यते ॥

(प्रदीपः) पूर्वोत्तरयोः-इति कर्मणि षष्ठी । योगः=संबन्धः । तदयमर्थः—अच्युपश्लिष्टस्येको यणा भाव्यम् । यथाऽचि परस्मिन् पूर्व उपश्लिष्टः, एवं पूर्वस्मिन्नपि परः ॥ तिङ्ङतिङ इत्यत्रापि यथाऽतिङन्तात्परं तिङन्तं भवति, एवं पूर्वमपि । तत्र षष्ठीप्रक्लृप्तिपक्षे षष्ठ्यनुवर्तयितव्या-इति गौरवप्रसङ्गान्नियमार्थमित्युक्तम् ॥ योगयोरिति । युज्येते इति-योगौ, कर्मणि घञ् । अचीति सत्सप्तमीपक्षेऽप्यनियमप्रसङ्गः ॥ अचि पूर्वस्येति । उपपदविभक्तेः कारकविभक्तिर्बलीयसीति न्यायादधिकरणसप्तमी कृता, न तु दिग्योगलक्षणा पञ्चमी । तत्र दध्युदकमित्यादौ पर्यायप्रसङ्गः । न हि युगपदेकस्य स्थानित्वं निमित्तत्वं चोपपद्यत इति नियमार्थं वचनं-पूर्वस्यैवाऽनन्तरस्यैव भवतीति ॥ द्वयं चानेन क्रियते-परनिवृत्तिर्व्यवहितनिवृत्तिश्च । संदेहस्तूपक्रममात्रतयोपन्यस्तः । न हि संदेहादलक्षणमिति न्यायात् पर्यायप्रसङ्गात् ॥

(उद्द्योतः) ननु पूर्वोत्तरयोर्योगयोरिति भाष्यदर्शनेन

पूर्वोत्तरयोरित्यस्य धीगसमानाधिकरणत्वात्सापेक्षस्यासमर्थत्वेन योगाविशेष इति समासो न स्यादत आह—कर्मणि षष्ठीति । तथाच क्रियायाः कारकांशे नित्यसापेक्षत्वेनाविरुद्धः समास इति भावः ॥ पूर्वोत्तरयोर्योगयोरिति तु फलितार्थकथनम् ॥ अभ्युपश्लिष्टस्येति । औपश्लेषिकेऽधिकरणे सप्तमीति भावः ॥ आद्यसूत्रोदाहरणम्—दध्युदेति ॥ द्वितीयसूत्रोदाहरणम्—पचत्विति ॥ ननु नियमपक्षात्पष्ठीप्रकृतिपक्षः प्रशस्तोऽनुवाददोषाभावादत आह—तत्र षष्ठीति ॥ भाष्ये - योगयोरिति द्विवचनोपपत्तये आह—कर्मणीति । युग्यमानयोः पूर्वपरयोरविशेषात्–संबन्धाविशेषादित्यर्थः ॥ वस्तुतस्तु व्यधिकरणे षष्ठ्यौ, प्रतियोगिद्वित्वेन संबन्धद्वित्वाच्च द्विवचननिर्देश इति बोध्यम् ॥ सत्सप्तमीपक्षेऽपीति । यस्य च भावेनेति सप्तमीति भावः ॥ इदं चिन्त्यमित्याह—उपपदविभक्तेरिति । कारकविभक्तित्वं च कारकाधिकारपठितसंज्ञानिमित्तकविभक्तित्वम् । एतच्च तत्र च दीयत इति सूत्रे कैयटे स्पष्टम् ॥ न तु दिग्योगेति । सत्सप्तम्या अप्युपलक्षणमिदम् । एतच्च श्वाल्लोप इत्यत्र निरूपयिष्यामः ॥ पर्यायस्यैवापादने बीजमाह—न हि युगपदिति । स्थानित्वे हि कार्यित्वेन प्राधान्यं निवर्त्यत्वं च, निमित्तत्वे च पारार्थ्येन गुणत्वं सत्त्वं च । तच्चोभयमेकदा एकस्य विरुद्धमिति भावः ॥ ननु सन्देह इति भाष्योक्त्या शास्त्रस्य मूकत्वमित्याभाति, अत आह—सन्देहरित्वति ॥

(काकुभाष्यम्)

अस्ति प्रयोजनमेतत् ?

(समाधानभाष्यम्)

किं तर्हीति ?

(उभयनिर्देशे पञ्चमीनिर्देशबलीयस्त्वबोधनम्)

(आक्षेपभाष्यम्)

अथ यत्रोभयं निर्दिश्यते, किं तत्र पूर्वस्य कार्यं भवति । आहोस्वित् परस्येति ?

(प्रदीपः) अथ यत्रेति । यथा वहोर्लोप इत्यत्र । युगपदेकस्य कार्यित्वनिमित्तत्वासंभवात् प्रश्नः ॥

(३७७ समाधानवार्तिकम् ॥ १ ॥)

॥ * ॥ उभयनिर्देशे विप्रतिषेधात्पञ्चमीनिर्देशः ॥ * ॥

(भाष्यम्)

उभयनिर्देशे विप्रतिषेधात्पञ्चमीनिर्देशो भविष्यति ॥

(प्रदीपः) विप्रतिषेधादिति । सूत्रपाठापेक्षया परस्य व्यवस्थापकत्वमित्यर्थः ॥

(उद्योतः) ननु कार्यकालत्वात्परिभाषयोः पौर्वापर्याभावात्कथं विप्रतिषेधोऽत आह—सूत्रपाठेति । अत एवाग्रे ङमो ह्रस्वादिति त्रैपादिकमुदाहरणं सङ्गच्छते । तत्र हि कार्यकालपक्षाश्रयेणैव परिभाषाप्रवृत्तिरिति बोध्यम् ॥

(भाष्यम्)

किं प्रयोजनम् ?

(प्रदीपः) किं प्रयोजनमिति । विभक्तिविशेषनिर्देशानवकाशत्वात्-इति वक्ष्यमाणोऽभिप्रायः ॥

(उद्योतः) विभक्तिविशेषनिर्देशस्यानवकाशत्वादिति । इदमुदाहरिष्यमाणोदाहरणविशेषापेक्षम् । अत एव ङः सि धुडित्यत्र द्वयोरनवकाशत्वेऽपि न क्षतिः ॥

(प्रयोजने भाष्यवार्तिकम्)

॥ प्रयोजनमतो लसार्वधातुकानुदात्तत्वे ॥

(भाष्यम्)

वक्ष्यति—*तास्यादिभ्योऽनुदात्तत्वे सप्तमीनिर्देशोऽभ्यस्तसिजर्थः * इति । तस्मिन् क्रियमाणे तास्यादिभ्यः परस्य लसार्वधातुकस्य, लसार्वधातुके परतस्तास्यादीनामिति संदेहः ॥ तास्यादिभ्यः परस्य लसार्वधातुकस्य ॥

(प्रदीपः) संदेह इति । संदेहाच्च पर्यायप्रसङ्गः ॥

(उद्योतः) भाष्ये—वक्ष्यति तास्यादिभ्य इति । तास्यनुदात्तेदिति सूत्रे ॥ अभ्यस्तसिजर्थ इति । अभ्यस्तानामादिः आदिः सिच इति सूत्रयोर्लसार्वधातुक इति सप्तम्यन्तानुवृत्तिसिद्ध्ये इत्यर्थः ॥

(प्रयोजने भाष्यवार्तिकम्)

॥ बहोरिष्ठादीनामादिलोपे ॥

(भाष्यम्)

बहोरुत्तरेषामिष्ठेमेयसाम्, इष्ठेमेयःसु परतो बहोरिति संदेहः ॥ बहोरुत्तरेषामिष्ठेमेयसाम् ॥

(प्रदीपः) इष्ठेमेयःस्विति । तदा च बहुशब्दस्य लोपभूभावौ पर्यायेण स्याताम् ॥

(प्रयोजने भाष्यवार्तिकम्)

॥ गोतो णित् ॥

(भाष्यम्)

गोतः परस्य सर्वनामस्थानस्य, सर्वनामस्थाने परतो गोत इति संदेहः ॥ गोतः परस्य सर्वनामस्थानस्य ॥

(प्रदीपः) गोतो णिदिति । यदि गोशब्दस्य णित्वं स्यात्तदा 'तिष्ठति गौः' इत्यत्र वचनसामर्थ्यादनङ्गस्यापि वृद्धिः स्यात् ॥

(उद्योतः) ननु भाष्ये सर्वनामस्थानस्य गोत इति षष्ठीदर्शनात् णिदित्यनेनान्वयो न स्यादत आह—णित्वमिति । भावप्रधानो निर्देश इति भावः ॥ गोतो णित्त्वे को दोषस्तत्राह—तिष्ठतीत्यादि ॥

(प्रयोजने भाष्यवार्तिकम्)

॥ रुदादिभ्यः सार्वधातुके ॥

(भाष्यम्)

रुदादिभ्यः परस्य सार्वधातुकस्य, सार्वधातुके

परतो रुदादीनामिति संदेहः ॥ रुदादिभ्यः परस्य सार्वधातुकस्य ॥

(प्रयोजने भाष्यवार्तिकम्)

॥ आने मुगीदासः ॥

(भाष्यम्)

आस उत्तरस्यानस्य, आने परत आस इति संदेहः ॥ आस उत्तरस्यानस्य ॥

(प्रयोजने भाष्यवार्तिकम्)

॥ आमि सर्वनाम्नः सुट् ॥

(भाष्यम्)

सर्वनाम्न उत्तरस्यामः, आमि परतः सर्वनाम्न इति संदेहः ॥ सर्वनाम्न उत्तरस्यामः ॥

(प्रयोजने भाष्यवार्तिकम्)

॥ घेर्ङित्याण् नद्याः ॥

(भाष्यम्)

नद्याः परेषां ङिताम्, ङित्सु परतो नद्या इति संदेहः ॥ नद्या उत्तरेषां ङिताम् ॥

(प्रयोजने भाष्यवार्तिकम्)

॥ याडापः ॥

(भाष्यम्)

आप उत्तरस्य ङितः, ङिति परस्य आप इति संदेहः ॥ आप उत्तरस्य ङितः ॥

(प्रयोजने भाष्यवार्तिकम्)

॥ ङमो ह्रस्वादचि ङमुट् नित्यम् ॥

(भाष्यम्)

ङम उत्तरस्याऽचः, अचि परतो ङमः इति संदेहः ॥ ङम उत्तरस्याचः ॥

(प्रदीपः) ङमो ह्रस्वादिति । ङमो ङमुडागमे सति 'कुर्वन्नास्ते' इत्यत्र णत्वप्रसङ्गः । पदस्य चैको नकारोऽन्तो न तु द्वावपि-इति 'पदान्तस्य' इति णत्वप्रतिषेधो नास्ति ॥

(उद्द्योतः) पदस्य चैक इति । व्यक्तिपक्षे इदम् । व्यक्तिपक्षेऽप्येवंविधप्रयोगसाधनायैवं व्याख्यानमिति भावः ॥ यद्वाऽन्तशब्दस्यावयववान्नित्वेनेदृशे विषये जातिग्रहणासंभव एवेत्याहुः ॥

(३७८ समाधानहेत्वनुपपत्तिवार्तिकम् ॥ २ ॥)

॥ * ॥ विभक्तिविशेषनिर्देशानवकाशत्वादविप्रतिषेधः ॥ * ॥

(भाष्यम्)

विभक्तिविशेषनिर्देशस्यानवकाशत्वादयुक्तोऽयं विप्रतिषेधः । सर्वत्रैवात्र कृतसामर्थ्या सप्तमी - अकृतसामर्थ्या पञ्चमीति कृत्वा पञ्चमीनिर्देशो भविष्यति ॥

(प्रदीपः) विभक्तीति । पूर्वोपात्तेषु सूत्रेषु सप्तमीनिर्देशस्य क्वचित् पूर्वार्थत्वात् क्वचिदुत्तरार्थत्वात् सावकाशत्वम् । पञ्चमी तु निरवकाशेति परस्य कार्यित्वं बोधयिष्यतीति भावः ॥

(उद्द्योतः) ङःसिधुडित्यादावुभयोरप्यनवकाशत्वादाह—पूर्वोपात्तेष्विति । बहोरिति पञ्चमी अचरितार्था । अत एवेष्ठादिषु षष्ठी । अत एव भू च बहोरिति पृथङ्निर्देशश्चरितार्थः । गोत इत्यादौ सर्वनामस्थाने इति सप्तमी पूर्वत्र चरितार्था । गोशब्दस्य णित्ववैयर्थ्यं च । तिष्ठति गौरित्यत्र गोशब्दं प्रति तिष्ठतेरनङ्गत्वान्न दोषः । रुदादिभ्यः सार्वधातुक इति लिङः सलोप इत्यादौ चरितार्थम् । तत्र हि सार्वधातुके विद्यमानस्य सस्य लोप इत्यर्थः ॥ आमि सर्वनाम्न इत्यामीति त्रेस्त्रय इत्यत्र सावकाशम् । ङम इति सूत्रेऽचीति मय उञ इति सूत्रे चरितार्थम् ॥ ॰॰- देशो भविष्यतीत्यस्य बलवान्स्वार्थे एव भविष्यतीत्यर्थः षष्ठ्यर्थे इति भावः ॥

(३७९ एकदेशिसमाधानवार्तिकम् ॥ ३ ॥)

॥ * ॥ यथार्थं वा षष्ठीनिर्देशः ॥ * ॥

(भाष्यम्)

यथार्थं वा षष्ठीनिर्देशः कर्तव्यः । यत्र पूर्वस्य कार्यमिष्यते तत्र पूर्वस्य षष्ठी कर्तव्या । यत्र परस्य कार्यमिष्यते तत्र परषष्ठी कर्तव्या ॥

(प्रदीपः) यथार्थं वेति । यथाविषयमित्यर्थः । प्रदेशेषु कार्यिणः षष्ठ्यैव निर्देष्टव्याः ॥

(उद्द्योतः) भाष्ये एकदेशी प्रौढ्याऽऽह—यथार्थं वेति । तत्र अर्थशब्दो न प्रयोजनादिवाचीत्याह—यथाविषयमिति ॥ प्रदेशेष्विति । प्रागुक्तेष्वित्यर्थः ॥ भाष्ये—पूर्वस्य षष्ठीति । पूर्वबोधकपदस्य षष्ठ्यन्तस्योच्चारणं कार्यमित्यर्थः ॥ एवं चोभयोच्चारणे गौरवमित्येकदेश्युक्तिरियम् ॥

(आक्षेपभाष्यम्)

स तर्हि तथा निर्देशः कर्तव्यः ॥

(उद्द्योतः) तत्र तत्र सप्तम्यन्तषष्ठ्यन्तयोर्द्वयोः पाठे गौरवं मत्वेतर एकदेशी आह—स तर्हीति ।

(आक्षेपनिरासैकदेशिभाष्यम्)

न कर्तव्यः । अनेनैव प्रक्लृप्तिर्भविष्यति—तस्मिन्निति निर्दिष्टे पूर्वस्य षष्ठी, तस्मादित्युत्तरस्य षष्ठीति ॥

(उद्द्योतः) एकदेशी प्रौढ्यैवाह—न कर्तव्यः । अनेनैवेति । षष्ठीपदानुवृत्तिगौरवादयमेकदेशी । उभयोः प्रकल्पकत्ववारणाय परत्वानवकाशत्वे चावश्यके इति च ॥ निर्दिष्टे पूर्वस्य षष्ठीति । पूर्वस्य कार्यित्वप्रतिपादनयोग्या षष्ठी तद्बोधकपदे भवतीत्यर्थः ॥ एवमुत्तरस्येत्यपि ॥

(आक्षेपभाष्यम्)

तर्हि षष्ठीग्रहणं कर्तव्यम् ॥

(समाधानभाष्यम्)

न कर्तव्यम् । प्रकृतमनुवर्तते ॥

क्व प्रकृतम् ?

"षष्ठी स्थानेयोगा" इति ॥

(३८० प्रकल्पकपक्षे दूषणवार्तिकम् ॥ ४ ॥)

॥*॥ प्रकल्पकमिति चेन्नियमाभावः ॥*॥

(भाष्यम्)

प्रकल्पकमिति चेन्नियमस्याभावः । उक्तं चैतत्—नियमार्थोऽयमारम्भ इति ॥

(प्रदीपः) प्रकल्पकमिति । यत्र षष्ठी नास्ति तत्र तस्याः क्लृप्तिः क्रियते । यत्र तु षष्ठ्यस्ति—इको यणचीत्यादौ, तत्रानेन न नियमः क्रियते । न हि व्यापारद्वयमुपपद्यते । येन षष्ठीप्रक्लृप्तिस्तस्याश्च नियम इति भावः ॥

(उद्द्योतः) न हीति । आवृत्तिप्रसङ्गादिति भावः ॥

(दूषणान्तरभाष्यम्)

प्रत्ययविधौ खल्वपि पञ्चम्यः प्रकल्पिकाः स्युः ॥

तत्र को दोषः ?

"गुप्तिज्किद्भ्यः सन्" । गुप्तिज्किद्भ्य इत्येषा पञ्चमी सन्निति प्रथमायाः षष्ठीं प्रकल्पयेत्—'तस्मादित्युत्तरस्य' इति ॥

(दूषणान्तरबाधकभाष्यम्)

अस्तु । न कश्चिदन्य आदेशः प्रतिनिर्दिश्यते । तत्राऽऽन्तर्यतः सनः सन्नेव भविष्यति ॥

(दूषणान्तरसाधकभाष्यम्)

नैवं शक्यम् । इत्संज्ञा न प्रकल्पेत । उपदेश इत्संज्ञोच्यते ॥

(प्रदीपः) इत्संज्ञेति । आदेशस्योपदेशाभावात्तस्येत्संज्ञा न सिध्यतीत्यर्थः । स्थानी चोत्पत्तिकाल एव निवृत्त्यभिमुखतया प्रतिपन्न इति स्थानिन्यपीत्संज्ञा नास्ति ॥

(उद्द्योतः) इतर एकदेशी 'उपदेशे' इति हलन्त्यमित्यत्रानुवर्तत इति मत्वाऽऽह—इत्संज्ञेति ॥ तद्व्याचष्टे—उपदेशाभावादिति । स्थानेऽन्तरतमपरिभाषयाऽनुमीयमानत्वेनादेशस्योच्चारणाभावादित्यर्थः ॥ ननु स्थानिन्येव तस्याः प्रवृत्तेरनुमीयमानादेशो निरनुबन्धक एवेत्यत आह—स्थानी चेति । यदा धातोः प्रत्ययस्तदानीमेवादेशो भवेदिति नेत्संज्ञादि प्रतीक्षते । यत्र कार्यं तत्रेत्संज्ञेति प्रयोग एवेत्संज्ञेत्यभिमानः । एकदेश्युक्तित्वादत्र नात्यन्तं निर्भरः कार्य इति बोध्यम् ॥

(३८१ प्रकल्पकपक्षे आक्षेपान्तरवार्तिकम् ॥ ५ ॥)

॥ * ॥ प्रकृतिविकाराव्यवस्था च ॥ * ॥

(भाष्यम्)

प्रकृतिविकारयोश्च व्यवस्था न प्रकल्पते । "इको यणचि" अचीत्येषा सप्तमी यणिति प्रथमायाः षष्ठीं प्रकल्पयेत्—"तस्मिन्निति निर्दिष्टे पूर्वस्य" इति ॥

(प्रदीपः) यणिति प्रथमाया इति । ततश्चेकः स्थाने यण् न लभ्यते । इकोऽप्यन्य आदेशः स्याद्यणोऽप्यन्य इत्यभिमता स्थान्यादेशभावव्यवस्था न स्यात् ॥

(उद्द्योतः) ततश्चेति । पूर्वस्य जायमानो यणपि पूर्व एवेति तत्रापि षष्ठीकल्पनमिति भावः ॥

(३८२ प्रकल्पकपक्षे आक्षेपान्तरवार्तिकम् ॥ ६ ॥)

॥ * ॥ सप्तमीपञ्चम्योश्च भावादुभयत्र षष्ठीप्रक्लृप्तिस्तत्रोभयकार्यप्रसङ्गः ॥ * ॥

(भाष्यम्)

सप्तमीपञ्चम्योश्च भावादुभयत्रैव षष्ठी प्राप्नोति । 'तास्यादिभ्यः' एषा पञ्चमी लसार्वधातुक इत्यस्याः सप्तम्याः षष्ठीं प्रकल्पयेत्—"तस्मादित्युत्तरस्य" इति ॥ तथा 'लसार्वधातुके' इत्येषा सप्तमी 'तास्यादिभ्यः' इति पञ्चम्याः षष्ठीं प्रकल्पयेत्—"तस्मिन्निति निर्दिष्टे पूर्वस्य" इति ॥

तत्र को दोषः ?

'तत्रोभयकार्यप्रसङ्गः' । तत्रोभयोः कार्यं प्राप्नोति ॥

(प्रदीपः) उभयकार्यप्रसङ्ग इति । विरोधाभावाद्यौगपद्येनोभयोः कार्यं प्राप्नोति ॥

(उद्द्योतः) विरोधाभावादिति । स्थानिभेदादित्यर्थः । अत एव विप्रतिषेधाप्रवृत्तिः । यद्यपि कार्यित्वनिमित्तत्वे युगपद्विरुद्धे, तथाप्येकदेश्युक्तित्वान्नात्यन्तं निर्भरः कार्य इति बोध्यम् ॥ एवमग्रेऽपि बोध्यम् ॥

(प्रकल्पकपक्षे दूषणोद्धारभाष्यम्)

नैष दोषः । यत्तावदुच्यते—* प्रकल्पकमिति चेन्नियमाभावः * इति । माभून्नियमः । सप्तमीनिर्दिष्टे पूर्वस्य षष्ठी प्रकल्प्यते, पञ्चमीनिर्दिष्टे परस्य । यावता सप्तमीनिर्दिष्टे पूर्वस्य षष्ठी प्रकल्प्यते, पञ्चमीनिर्दिष्टे परस्य । नोत्सहते सप्तमीनिर्दिष्टे परस्य कार्यं भवितुं, नापि पञ्चमीनिर्दिष्टे पूर्वस्य ॥

(प्रदीपः) मा भून्नियम इति । षष्ठीप्रक्लृप्त्यैव तत्फलस्य सम्पन्नत्वादिति भावः ॥ यत्र षष्ठी नास्ति तत्रासौ प्रकल्प्यते । यत्र त्वस्ति इको यणचीति, तत्रापि पूर्वस्यैव षष्ठी, न परस्येति प्रकल्प्यते ॥

(उद्द्योतः) यत्र त्वस्तीति । तस्मिन्नितीत्यस्य बहुविषयत्वलाभाय विषयभेदेन भेदात् केचित्पूर्वस्य षष्ठीति विधिपरम्, केचिन्नियमपरमित्यर्थः ॥

(आक्षेपबाधकभाष्यम्)

यदप्युच्यते—'प्रत्ययविधौ पञ्चम्यः प्रकल्पिकाः स्युः' इति ॥ सन्तु प्रकल्पिकाः ॥

(आक्षेपकारणभाष्यम्)

ननु चोक्तम्—'गुप्तिज्किद्भ्यः सन्' इत्येषा पञ्चमी सन्निति प्रथमायाः षष्ठीं प्रकल्पयेत्—'तस्मा-

दित्युत्तरस्य'—इति ॥

(परिहारस्मारणभाष्यम्)

परिहृतमेतत्—न कश्चिदन्य आदेशः प्रतिनिर्दिश्यते । तत्रान्तर्यात् सनः सन्नेव भविष्यति—इति ॥

(परिहारबाधकस्मारणभाष्यम्)

ननु चोक्तम्—'नैवं शक्यमित्संज्ञा न प्रकल्पेत । उपदेश इति इत्संज्ञोच्यते'—इति ॥

(परिहारबाधानुपपत्तिभाष्यम्)

स्यादेष दोषो यदीत्संज्ञा आदेशं प्रतीक्षेत । तत्र खलु कृतायामित्संज्ञायां लोपे च कृते आदेशो भविष्यति । उपदेश इति हीत्संज्ञोच्यते ॥

(प्रदीपः) कृतायामित्संज्ञायामिति । सूत्र एवोच्चारितस्य इत्संज्ञा-इति प्रयोगे 'स'शब्द एव 'सन्'कार्यं लभत इत्यर्थः ॥

(उद्योतः) सूत्र एवेति । षष्ठीप्रक्लृप्तेः प्रागेव परत्वादन्तरङ्गत्वाच्च उपदेशोत्तरकालमत्र एवेत्संज्ञा । कार्यं तु प्रयोग एवेति भावः । एवंच निरनुबन्धस्यैव प्रत्ययत्वेन विधानात्तदादेशस्य कुतः सानुबन्धकतेति तात्पर्यम् ॥ भाष्ये—उपदेश इति हीत्संज्ञोच्यत इति । एवंच त्वदुक्तिर्व्याहतेति भावः ॥

(परिहारान्तरभाष्यम्)

अथवा—नानुत्पन्ने सनि प्रक्लृप्त्या भवितव्यम् । यदा चोत्पन्नः सन्, तदा कृतसामर्थ्या पञ्चमीति कृत्वा प्रक्लृप्तिर्न भविष्यति ॥

(प्रदीपः) अथवेति । परत्वविशिष्टस्य सन उत्पादेन उपक्षयात् प्रवृत्त्यन्तराभावान्नास्ति पञ्चम्याः प्रकल्पकत्वमित्यर्थः ॥

(उद्योतः) हलन्त्यसूत्रे उपदेशपदासंबन्ध एव-इति तत्सूत्र-वक्ष्यमाणपक्षेऽप्याह—अथवेति ॥ परत्वविशिष्टस्येति । अनुत्पत्तौ धातोः परस्येति वक्तुमशक्यत्वादिति भावः ॥ उपक्षयादिति । पञ्चम्या इति शेषः ॥ प्रवृत्त्यन्तराभावादिति । पुनः प्रवृत्तौ मानाभावादिति भावः ॥

(आक्षेपान्तरबाधकभाष्यम्)

यदप्युच्यते—* प्रकृतिविकाराव्यवस्था च *—इति ॥

तत्रापि कृता प्रकृतौ षष्ठी—'इकः' इति, विकृतौ प्रथमा-'यण्' इति । यत्र च नाम सौत्री षष्ठी नास्ति, तत्र प्रक्लृप्त्या भवितव्यम् ॥

(प्रदीपः) प्रकृतौ षष्ठीति । इको यणचीति श्रुतयोरेव स्थान्यादेशभावोपादानान्नास्ति षष्ठीप्रकल्पनम्, अपेक्षाया अभावादित्यर्थः ॥

(उद्योतः) अपेक्षाया इति । श्रुतयोः संबन्धाभावे हि तस्मिन्नित्यनेन षष्ठीप्रक्लृप्त्यपेक्षा । न च प्रकृते तथा । श्रुतिर्लिङ्गाच्छ्रुतेर्बलीयस्त्वादित्यर्थः ॥

(भाष्यम्)

अथवा—अस्तु तावदिको यणिति यत्र नाम सौत्री षष्ठी ॥ यदि चेदानीमचीत्येषा सप्तमी यणिति प्रथमायाः षष्ठीं प्रकल्पयेत्—'तस्मिन्निति निर्दिष्टे पूर्वस्य' इति ॥

अस्तु । न कश्चिदन्य आदेशः प्रतिनिर्दिश्यते । तत्राऽऽन्तर्यतो यणो यणेव भविष्यति ॥

(उद्योतः) भाष्ये—अथवाऽस्तु तावदिति । प्रथमा-षष्ठीनिर्देशसामर्थ्यात् प्रथमत इग्यणोः स्थान्यादेशभावोऽस्तु । तत एतत्सूत्रबलाद्यणः स्थानित्वेऽपि न क्षतिरित्यर्थः ॥ यत्र नाम सौत्री षष्ठी । यदि चेदानीमिति । यत्र सौत्री षष्ठ्यस्ति तत्रापीदानीं यदि प्रकल्पयेत्तर्हि अस्तु-प्रकल्पयत्वित्यर्थः ॥ परं त्विदं प्रौढ्या, अथवा नानुत्पन्ने सनीति प्रागुक्तन्यायात् ॥ गाङ्कुटादिभ्य इत्यादौ षष्ठी-प्रक्लृप्तावपि न दोषः, ञित्पदस्य धर्मपरत्वादिति बोध्यम् ॥

(आक्षेपान्तरबाधकभाष्यम्)

यदप्युच्यते—*सप्तमीपञ्चम्योश्च भावादुभयत्र षष्ठीप्रक्लृप्तिस्तत्रोभयकार्यप्रसङ्गः *—इति ॥ आचार्यप्रवृत्तिर्ज्ञापयति—'नोभे युगपत्प्रकल्पिके भवतः' इति । यदयम् "एकः पूर्वपरयोः" इति पूर्वपरग्रहणं करोति ॥ तस्मिन्निति निर्दिष्टे पूर्वस्य ॥ ६६ ॥ तस्मादित्युत्तरस्य ॥ ६७ ॥

(प्रदीपः) यदयमिति । यद्युभयनिर्देशात्परस्परषष्ठी-प्रकल्पने सति ग्रहणकवाक्याद्वाक्यान्तरमनुमीयते—तास्यादिभ्यो लसार्वधातुकस्य लसार्वधातुके तास्यादीनामनुदात्तत्वं भवतीति तदा 'आद्गुणः' इत्यादावपि तथैव प्रक्लृप्तिर्भविष्यतीति किं पूर्वपरयोरित्यनेनेत्यर्थः । तत्र परत्वानवकाशत्वाभ्यां नियमपक्षवत् षष्ठीप्रकल्पनपक्षे व्यवस्था । दीर्घाच्छे तुक् भवतीत्यत्र षष्ठीस्थाने व्यत्ययेन पञ्चमीति व्याख्यानात् सुराछायेत्यादेर्वा ज्ञापकात् दीर्घस्यैव तुग् भवति, न तु छस्य ॥ ६६ ॥ ६७ ॥

(उद्योतः) यद्यपि युगपत् प्रक्लृप्तिर्विरोधान्न संभवति, तथाप्येकदेशित्वादेव ज्ञापकेन परिहरति—नोभे इत्यादिना ॥ तथैव प्रक्लृप्तिरिति । अवर्णादचि अवर्णस्याचश्चैको गुणो भवतीत्यर्थ इति भावः ॥ ननूभयोः प्रकल्पकत्वाभावेऽपि एकस्य कस्य प्रकल्पकत्वमत आह—तत्र परत्वेति ॥ इः सिधुङित्यादौ परत्वमुक्तेष्वनवकाशत्वमिति भावः ॥ ननु दीर्घादिति सूत्रे पञ्चम्या अनवकाशत्वेन परत्वेन च छकारे षष्ठीप्रकल्पनं स्यादत आह—दीर्घाच्छे इति ॥ सुराछायेति । पदान्ते तुको वैकल्पिकत्वाच्चिन्त्यमिदम् । तुक्सहितं पाणिनिपाठमभिप्रेत्य तु ज्ञापकोपन्यासः । युक्तश्च तथा पाठः, वैकल्पिकेषु भावानुष्ठानस्य धर्माधिक्यफलकत्वात् ॥ ६६ ॥ ६७ ॥

(१२ संज्ञासूत्रम् ॥ १ । १ । ९ आ. ८ सू.)

स्वं रूपं शब्दस्याशब्दसंज्ञा ॥ १।१।६८ ॥

(प्रदीपः) स्वं रूपं शब्द० ॥ ६८ ॥ स्वरूपस्य पर्यायाणां

तद्विशेषाणां च ग्रहणे प्राप्ते नियमार्था परिभाषेयमिति केचिदाहुः ॥ अन्ये तु लिङ्गाभावात् विध्यन्तरशेषभावाभावाच्च नेयं परिभाषा, अपि तु संज्ञासूत्रमिदमिति प्रतिपन्नाः । देवदत्तादयश्च संज्ञाशब्दा नियमार्था इति सिद्धान्तः । 'सर्वार्थप्रत्यायनशक्तियुक्तो हि शब्दः' 'सर्वशब्दप्रत्याय्यशक्तियुक्तश्चार्थः' इति व्यवहाराय नियमः क्रियते । रूपशब्देन चेहाग्निशब्दत्वादिकं शुकसारिकापुरुषोदीरितभिन्नशब्दव्यक्तिसमवेतं सामान्यमभिधीयते । तत्र 'व्यक्तेः सामान्यं संज्ञा' 'सामान्यस्य वा व्यक्तिः' इति व्याख्याने कामचारः । व्यक्तिः कार्यं प्रतिपद्यमाना सामान्यप्रतिबद्धैव प्रतिपद्यते, सामान्यमपि कार्यं प्रतिपद्यमानं व्यक्तिद्वारेणैव प्रतिपद्यते इति फले न कश्चिद्भेदः ॥

(उद्योतः) स्वं रूपं० ॥ ६८ ॥ स्वरूपस्येति । शब्देनार्थप्रतीतावर्थे केषांचित्कार्याणामसंभवाच्छब्दाचकशब्दमात्रग्रहणादिति भावः ॥ अन्ये त्विति । शब्दस्य स्वरूपमिह ग्राह्यत्वेन विधित्सितमिति नेह प्रदेशविशेषसमर्पकं लिङ्गमस्तीति भावः ॥ ननु 'शब्दस्य' इत्येव लिङ्गम्, यत्र शब्दग्रहणं तत्र स्वरूपमेव ग्राह्यं न तु पर्यायादीत्यर्थः । तेन 'जनपदे' 'अपत्यं' इत्यादौ नास्याः प्रवृत्तिरत आह—विध्यन्तरेति । न हि स्वं रूपमित्यस्याग्नेर्ढगित्यादौ गम्यन्तेन सामानाधिकरण्येन वैयधिकरण्येन वा संबन्धः संभवतीति भावः ॥ भाष्यकारोऽप्याह—रूपं शब्दस्य संज्ञेति-इत्ययमेव पक्षो युक्तः ॥ ननु संज्ञापक्षे उभयगतिन्यायाद् एकस्यानेकार्थसंभवाच्चार्थस्यापि प्रतीतौ तत्र कार्यासंभवे ढगादयः पर्यायादिभ्योऽपि दुर्वारा इत्यत आह—देवदत्तादयश्चेति ॥ नियमार्थत्वमुपपादयति—सर्वार्थेति ॥ एकस्य सकलशब्दार्थात्मकस्फोटस्यैव सर्वबोधकत्वादिति भावः ॥ शक्तियुक्त इति । शक्त्याश्रय इत्यर्थः ॥ सर्वशब्दप्रत्याय्यशक्तिरिति । प्रत्याय्यत्वशक्तियुक्त इत्यर्थः ॥ अनेन नियमद्वयं दर्शितम्—अनेन शब्देनायमेवार्थो ग्राह्यः, अयमर्थोऽनेनैव शब्देन बोधनीय इति चेति ॥ वस्तुतस्तु सर्वेषां सर्वार्थवाचकत्वेऽपि तज्ज्ञानमस्मदादिज्ञानविषयः, सर्वार्थशब्दानामस्माकं विशिष्याज्ञानात् । किंतु योगिनामेव तज्ज्ञानम् । एवंच शास्त्राधिकारिणोऽस्मदादीन्प्रति नियमार्थत्वं शास्त्रस्यासंभव्येव । इयं कथा तु सर्वस्य ब्रह्मरूपत्वकथावन्न व्यवहारोपयोगिनी । तस्मात् प्रकरणादस्यैवार्थस्य शास्त्रे उपस्थितौ अर्थान्नियमः फलित इति बोध्यम् ॥ तत्र द्वितीयो नियमश्चिन्त्यः, आकारादीनां वृद्धिशब्दातिरिक्तैराकारादिशब्दैर्व्यवहारानापत्तेरिति केचित् ॥ ननु रूपरूपिणोरत्र भेदाभावाच्छब्दस्येति षष्ठ्यनुपपन्ना, संज्ञासंज्ञिसंबन्धश्चानुपपन्न इत्यत आह—रूपेति ॥ सामान्यलक्षणघटकानेकसमवेतत्वसिद्धये आह—शुकेति । न च तैरुच्चारणक्रियैव भिद्यते न शब्द इति वाच्यम् । ताल्वादिव्यापाररूपस्योच्चारणस्याश्रोतत्वेन शब्दश्रवणानन्तरं जायमानवक्तृविशेषानुमानानापत्तेः, उदात्तत्वादिविरुद्धधर्माध्यासाच्च भेदसिद्धेः, वर्णनिष्ठतया प्रतीयमानानां ध्वनिनिष्ठत्वकल्पने मानाभावात्—इति भावः ॥ ननु प्रायेण सामानाधिकरण्यं संज्ञासंज्ञिनोर्दृष्टम्, न चेह तदित्यत आह—तत्रेति ॥ स्वशब्दो व्यक्तिबोधक आत्मीयत्वेन । एवंच शब्दस्य तत्तज्जातिविशिष्टस्य स्वं-व्यक्तिः रूपं-सामान्यसंज्ञकमित्याद्यः पक्षः । शब्दस्य रूपमित्युद्दिश्य स्वमित्यनेन व्यक्तिसंज्ञकत्वं विधीयत इति द्वितीयपक्षसंभवः, सामानाधिकरण्यस्य चोपपत्तिः । न चानयोः पक्षयोः फले कश्चिद्विशेष इत्याह—व्यक्तिरिति ॥ व्यक्तिद्वारेणेति । सामान्यस्य ढगादिभिः साक्षात्पौर्वापर्यासंभवादिति भावः ॥

—

(अर्थवत्परिभाषासाधनम्)

(आक्षेपभाष्यम्)

रूपग्रहणं किमर्थम् । न 'स्वं शब्दस्याशब्दसंज्ञा' भवति-इत्येव रूपं शब्दस्य संज्ञा भविष्यति । न ह्यन्यत् स्वं शब्दस्यास्ति अन्यदतो रूपात् ?

(प्रदीपः) **रूपग्रहणमिति** । प्रतीतावुपदेशानपेक्षत्वादन्तरङ्गत्वादहेयत्वादसाधारणत्वाच्च रूपमेव ग्रहीष्यते । अर्थो हि सम्बन्धग्रहणमपेक्षते । अनुकरणशब्देषु नार्थः प्रतीयते । साधारणश्च पर्यायैरपि प्रत्यायनात् । न चार्थः संज्ञा शक्यते वक्तुं, संज्ञित्वे चार्थस्य सूत्रमनर्थकमिति प्रश्नः ॥

(उद्योतः) रूपग्रहणं किमर्थमिति भाष्यस्य—स्वशब्देनैव जातिर्व्यक्तिर्वा । शब्दस्य स्वं—स्वीया जातिर्व्यक्तिर्वा बोध्येत्यर्थो भविष्यति । सामानाधिकरण्यमेव संज्ञासंज्ञिनोरिति तु न नियमः, उभ इत्यादौ व्यभिचारादित्याशयः । शब्दस्य सूत्रोच्चारितस्य स्वं—स्वीयं रूपं प्रयोगस्थं संज्ञीत्यर्थ इति केचित् ॥ भाष्ये—रूपं शब्दस्य संज्ञेति । अत्र संज्ञाशब्दो बोध्यपरः, कर्मव्युत्पत्तेः । अन्यथा स्वशब्देनार्थग्रहणाय रूपग्रहणमित्युत्तरभाष्यासङ्गतेः । न ह्यर्थः शब्दस्य संज्ञा, किंतु बोध्य एवेति बोध्यम् ॥ तत्रात्मीयवाचिना स्वशब्देन रूपस्यैव कथं परिग्रह इत्यत आह—प्रतीताविति ॥ उपदेशः—संबन्धग्रहणम् ॥ अन्तरङ्गत्वं—प्रथमतः श्रोत्रेणोपस्थित्या ॥ अहेयत्वमुपपादयति—अनुकरणेति । शब्दमात्रतात्पर्यकोच्चारणस्यैवानुकरणत्वात् ॥ अर्थस्य रूपतुल्यत्वमभ्युपेत्याप्याह—न चार्थ इति । शब्दात्मिकानामेवार्थानां वर्तनीत्वेन संज्ञात्वात्, तादृशसंबन्धा व्यवहाराच्चेति भावः ॥ ननु स्वंशब्दस्याभिधेयमित्येवार्थोऽस्त्वित्यत आह—संज्ञित्वे चेति । लोकत एव सिद्धेरिति भावः ॥

(समाधानभाष्यम्)

एवं तर्हि सिद्धे सति यद्रूपग्रहणं करोति तज्ज्ञापयत्याचार्यः—अस्त्यन्यद्रूपात्स्वं शब्दस्येति ॥

किं पुनस्तत् ?

अर्थः ॥

किमेतस्य ज्ञापने प्रयोजनम् ?

'अर्थवद्ग्रहणे नानर्थकस्य' इत्येषा परिभाषा न कर्तव्या भवति ॥

(प्रदीपः) **एवं तर्हीति** । यत एवेह रूपग्रहणस्य व्यावर्त्यं नास्ति तत एव ज्ञापकम् । सति तु व्यावर्त्ये तत्रैवोपक्षयान्न ज्ञापकं स्यात् ॥ **अर्थवद्ग्रहण इति** । अर्थयुक्तं रूपं गृह्यत इत्यर्थः । तेन काशे-कुशे-इत्यत्र 'शे' इति प्रगृह्यसंज्ञा

न भवति । यत्र चार्थवता रूपेण शब्दो नाश्रीयते तत्रेदं नोपतिष्ठते । यथा—वर्णग्रहणेषु, टेरेत्वे च - इति 'पचेते' इत्यत्रा-नर्थकस्यापि टेरेत्वं भवति ॥

(उद्योतः) ज्ञापकमिति । स्वशब्देन बहिरङ्गस्याप्यर्थस्य ग्रहणे - इत्यर्थः ॥ नन्वन्यस्य स्वीयस्य सत्त्वे तद्व्यावृत्त्यर्थं रूपग्रहण-मित्यर्थो भाष्यालभ्यते । एवं च शास्त्रेऽर्थस्याग्रहणे कथमर्थवत्परिभा-षासिद्धिरिति चेन्न । अन्यस्वीयमस्ति यतोऽतस्तस्यापि शब्दबोध्यस्य-बोधनार्थमुभयोपादानमिति भाष्याशयात् । एवं चाधिकसत्त्वग्रहार्थं रूपग्रहणम् । रूपग्रहणेन चान्तरङ्गत्वादिन्यायबाधपूर्वकं स्वशब्देना-र्थस्य शब्दबोध्यत्वं बोध्यत इति तात्पर्यम् ॥ तेनोभयानुग्रहाय सति संभवेऽर्थवतो रूपस्य ग्रहणम् । असति तु केवलार्थस्य शुद्धस्य वा रूपस्य ग्रहणम् । तदाह—यत्र चार्थवतेत्यादि । अर्थोपस्थापकेन रूपेणेत्यर्थः । अत एव भिन्नविभक्तिनिर्देशश्चरितार्थः ॥

(सूत्रप्रयोजनम्)

(आक्षेपभाष्यम्)

किमर्थं पुनरिदमुच्यते ?

(प्रदीपः) **किमर्थमिति** । वक्ष्यमाणोऽभिप्रायः ॥

(३८३ समाधानवार्तिकम् ॥ १ ॥)

॥ * ॥ शब्देनार्थगतेरर्थस्यासंभवात् तद्वाचिनः संज्ञाप्रतिषेधार्थं स्वरूपवच-नम् ॥ * ॥

(भाष्यम्)

शब्देनोच्चारितेनार्थो गम्यते - गामानय, दध्यशा-न - इति । अर्थ आनीयते, अर्थश्च भुज्यते ।

'अर्थस्यासंभवात्' । इह च व्याकरणे अर्थे कार्यस्या-संभवः—"अग्नेर्ढक्" इति, न शक्यतेऽङ्गारेभ्यः परो ढक् कर्तुम् । शब्देनार्थगतेरर्थस्यासंभवात् यावन्तस्तद्वाचिनः शब्दास्तावद्भ्यः सर्वेभ्य उत्प-त्तिः प्राप्नोति । इष्यते च—तस्मादेव स्यादिति । तच्चान्तरेण यत्नं न सिध्यतीति तद्वाचिनः संज्ञाप्रति-षेधार्थं स्वरूपवचनम् ॥ एवमर्थमिदमुच्यते ॥

(प्रदीपः) **शब्देनार्थगतेरिति** । कात्यायनवचनप्रामा-ण्यात् 'अस्त्रियाम्' इति प्रतिषेधस्यानित्यत्वात् विभाषा गुणे स्त्रियां पञ्चमी । इह योग्यतालक्षणेन संबन्धेन शब्दोऽर्थं लोके प्रत्याययति । व्याकरणेऽपि पशुः - अपत्यं - देवता - प्राग्वः - उदवः - भरताः - इत्यर्थ एव गृह्यते । अग्नेर्ढगित्यादौ त्वर्थस्य प्रत्ययेन पौर्वापर्यासंभवात् साहचर्यात् सर्वस्य तद्वाचिनः संप्रत्ययः स्यादिति सूत्रारम्भः ॥ **संज्ञाप्रतिषेधार्थमिति । संज्ञा-**सम्प्रत्यय उच्यते ॥

(उद्योतः) इह योग्यतेति । योग्यता—बोधजनकतारूपा तया लक्ष्यते=कल्प्यत इति योग्यतालक्षणः—शक्तिः, तया उभया-श्रयकत्वेन उभयाधीनत्वलक्षणगुणयोगाद् गौण्या वृत्त्या वा संबन्ध-पदव्यवहार्यत्वमिति बोध्यम् ॥ इत्यर्थ एवेति ॥ अर्थे कार्यस्य संभवादिति भावः ॥ ननु संज्ञाविधायकस्य तत्प्रतिषेधार्थकत्वमयुक्तमत आह—संप्रत्यय इति । भावेऽजिति भावः ॥

(३८४ समाधाननिराकरणवार्तिकम् ॥ २ ॥)

॥ * ॥ न वा शब्दपूर्वको ह्यर्थे संप्रत्यय-स्तस्मादर्थनिवृत्तिः ॥ * ॥

(भाष्यम्)

न वा एतत्प्रयोजनमस्ति ॥

किं कारणम् ?

'शब्दपूर्वको ह्यर्थे संप्रत्ययः' । आतश्च शब्दपूर्वकः । योऽपि ह्यसावाहूयते नाम्ना । नाम च यदाऽनेन नोपलब्धं भवति, तदा पृच्छति—'किं भवानाह' इति, शब्दपूर्वकश्चार्थस्य प्रत्ययः ॥ इह च व्याक-रणे शब्दे कार्यस्य संभवः ॥ 'तस्मादर्थनिवृत्तिः ।' तस्मादर्थनिवृत्तिर्भविष्यति ॥

(प्रदीपः) **न वेति** । शब्द उपलब्धोऽर्थं प्रत्याययति, न सत्तामात्रेण । चक्षुरादीनि तु सत्तामात्रेण विषयमवगम-यन्ति । अर्थस्य शास्त्रीये कार्ये क्वचिदयोग्यत्वात् प्रत्यासत्त्या स एवोपात्तः शब्दो ग्रहीष्यते, न विप्रकृष्टं शब्दान्तरमिति-भावः ॥ **शब्दपूर्वक इति** । अस्योपलब्धुः शब्दपूर्वक इत्यर्थः ॥

(उद्योतः) नन्वर्थप्रत्ययस्य शब्दपूर्वकत्वेऽपि कथं स्वरूपस्यैव ग्रहणमत आह—शब्द इति । तथा च प्रथमप्रतीतत्वरूपकार-णादुच्चारितशब्दस्यैव ग्रहणं युक्तमिति भावः ॥ शब्दपूर्वक इत्यस्य शब्दज्ञानपूर्वक इत्यर्थः ॥ प्रत्यासत्त्येति । अर्थबोधानुकूलत्वेन ज्ञाते प्रथमप्रतीते शब्द एवार्थेऽसंभवे कार्यम्, न तु तत्पर्यायादिष्विति भावः ॥ अर्थे कार्यसंभवे तु तस्यैव । एवं चोपस्थितस्यार्थस्य सर्वथा त्यागे मानाभावाद् अर्थवत्परिभाषाऽपि सूत्रं विना सिद्धेति तात्प-र्यम् ॥ एवं चैतच्छ्यायानुवादकमिदं सूत्रं मन्दमत्यनुग्रहायेति बोध्यम् ॥ ननु अर्थज्ञानोत्तरं परं प्रति तद्बोधनाय शब्दप्रयोग इति कथं शब्द-पूर्वकत्वमर्थप्रतीतेरत आह—अस्योपलब्धुरिति । श्रोतुरित्यर्थः ॥ भाष्ये—शब्दपूर्वको हीति । हिः प्रसिद्ध्यर्थः । श्रोतुः शब्दज्ञान-पूर्वकोऽर्थप्रत्यय इति लोकप्रसिद्धमित्यर्थः ॥ युक्त्यन्तरमप्याह—आतश्चेति । एवं च शब्दस्यार्थप्रतीतौ कारणत्वादर्थे कार्यासंभवे तद्बोधकारणत्वेनोपस्थिते शब्दे कार्यमिति भावः ॥ इदानीं तत्त-च्छब्दजन्यार्थबोधे प्रकारतया भासमानशब्द एव कार्यमर्थेऽसंभवे इत्याह—शब्दपूर्वकश्चेति । शब्दविशेषणकश्चार्थविशेष्यकः प्रत्यय इत्यर्थः ॥ न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते इति भावः ॥ चकारेण चास्य युक्त्यन्तरत्वं सूचितम् ॥ भाष्ये—तस्मादर्थनिवृत्तिरिति । अर्थवाचकशब्दान्तरनिवृत्तिरित्यर्थः ॥

(प्रयोजनभाष्यम्)

इदं तर्हि प्रयोजनम्—'अशब्दसंज्ञा' इति वक्ष्या-मीति । इह मा भूत्—"दाधा घ्वदाप्" "तरप्-

तमपौ घः" इति ॥

(प्रदीपः) अशब्दसंज्ञेति । न्यायात् स्वरूपग्रहणे सिद्धे शब्दसंज्ञायां स्वरूपग्रहणं प्रा भूदित्येवमर्थमिदमित्यर्थः । अन्यथोपसर्गे घोः किरिति किः प्रत्ययो घोर्धातोः शब्दार्थात् स्यात्, न तु दाधाभ्यः । 'कुमारीघः' इत्यत्र घरूपकल्पेति ह्रस्वः प्रसज्येत ॥ ई हल्यघोरित्यत्र तु घुशब्दस्याकारान्तत्वाभावाद्दाधामेव ग्रहणं सिद्धमिति ॥

(उद्द्योतः) फलान्तरं शङ्कते—इदं तर्हीति ॥ एवमर्थमिति । निषेधप्रतियोगिज्ञानार्थं न्यायसिद्धस्यापि विध्यंशस्यानुवाद इत्यर्थः ॥ किप्रत्यय इति । न चैवं पेषंवासवाहनधिषु चेति धिग्रहणं व्यर्थं स्याद् । न हि धाधातोः किं विना उदकस्य घ्युत्तरपदत्वं संभवति । तत्र हि कर्मण्यधिकरणे चेति तदुत्तरसूत्रेण किरिति वाच्यम् । उपलक्षणमिदं, सनि मीमाघु-नेर्गदेत्यादौ घुधातोर्ग्रहणं स्यादिति बोध्यम् ॥ कुमारीघ इति । ननु अयं षष्ठीतत्पुरुषः कर्मधारयो वा, उभयथाऽपि नात्र प्राप्तिः, तत्र स्त्रियां समानाधिकरण इत्यनुवृत्तेरिति चेत्, घोऽस्त्यस्याः सा-घा, कुमारी घा अस्य इति बहुव्रीहौ कुमारीघ इत्यर्थात् । घादिषु ह्रस्वत्वं पुंवद्भावाद्विप्रतिषेधेनेत्युक्तेः पुंवत्त्वं बाधित्वा ह्रस्वप्राप्तिरत्रेत्याशयात् ॥ घुसंज्ञाविधानस्य तर्हि कोऽवकाश इत्यत आह—ई हलीति ॥ घसंज्ञाऽपि किमेत्तिङव्ययघादित्यादौ चरितार्था, तत्र हि तिङन्तात्परान्यघान्तप्रातिपदिकासंभवादिति बोध्यम् ॥

(३८५ प्रयोजननिराकरणवार्तिकम् ॥ १ ॥)

॥ * ॥ शब्दसंज्ञाप्रतिषेधानर्थक्यं वचनप्रामाण्यात् ॥ * ॥

(भाष्यम्)

शब्दसंज्ञाप्रतिषेधोऽनर्थकः ॥

शब्दसंज्ञायां स्वरूपविधिः कस्मान्न भवति ?

'वचनप्रामाण्यात्'। शब्दसंज्ञावचनसामर्थ्यात् ॥

(प्रदीपः) वचनप्रामाण्यादिति । प्रदेशेषु संज्ञिप्रत्यायनार्थं संज्ञाकरणमिति सामर्थ्यात् स्वरूपग्रहणं न भविष्यति ॥

(उद्द्योतः) प्रदेशेष्विति । सर्वप्रदेशेष्वित्यर्थः । संज्ञावचनसामर्थ्यगम्यप्रकरणात् प्रत्यासत्तिन्यायो बाध्यत इत्यभिप्रायः । न च 'ईहल्यघोः' 'किमेत्तिङव्ययघ' इत्यत्र तयोश्चारितार्थ्यम् । तावन्मात्रफलकत्वे तत्रैव दाधाग्रहणं तरसमब्ग्रहणं च कुर्यात् इति बोध्यम् ॥

(प्रयोजनसाधकभाष्यम्)

ननु च वचनप्रामाण्यात् संज्ञिनां संप्रत्ययः स्यात्, स्वरूपग्रहणाच्च संज्ञायाः ॥

(प्रदीपः) ननु चेति । उभयगतिरिह शास्त्रे दृष्टा—सङ्ख्याकर्मकरणादिषु—इति इहापि स्वरूपस्य संज्ञिनश्च प्रदेशेषु ग्रहणं स्यात् ॥

(उद्द्योतः) उभयगतिरिति । संज्ञावचनस्य प्रत्यासत्तेश्चानुग्रहायोभयगतिरिति भावः । सत्यारम्भमभ्युपेत्येदम् ॥

(प्रयोजनबाधकभाष्यम्)

एतदपि नास्ति प्रयोजनम् । आचार्यप्रवृत्तिर्ज्ञापयति—शब्दसंज्ञायां न स्वरूपविधिर्भवतीति । यदयम्—"ष्णान्ता षट्" इति षकारान्तायाः संख्यायाः षट्संज्ञां शास्ति । इतरथा हि वचनप्रामाण्याच्च नकारान्तायाः संख्यायाः स्यात्, स्वरूपग्रहणाच्च षकारान्तायाः ॥

(प्रयोजनसाधकभाष्यम्)

नैतदस्ति ज्ञापकम् । न हि षकारान्ता संज्ञा ॥

का तर्हि ?

डकारान्ता ॥

(प्रदीपः) न हीति । षड्भ्यो लुगित्यादावुच्चारितेति भावः ॥ का तर्हीति । अत्र डकारान्तः शब्द उच्चारितः, जश्शसोश्च षकारान्ताल्लुक् कर्तव्यः । षण्णामिति च नुट् ॥

(उद्द्योतः) षड्भ्य इति । भाष्ये संज्ञाशब्दो बोधकपरः । न हि षकारान्तो बोधकशब्दस्तत्रोच्चारित इत्यर्थ इति भावः ॥ षकारान्ताविति । जश्शसोर्लुकः प्राक् जश्त्वाभावात् । एवं च तदर्थं तस्य षट्संज्ञा विधीयत इति न ज्ञापकत्वमिति भावः ॥

(प्रयोजनबाधकभाष्यम्)

असिद्धं जश्त्वम्, तस्यासिद्धत्वात् षकारान्ता ॥

(प्रदीपः) असिद्धमिति । डकारान्तः श्रूयमाणोऽपि डत्वस्यासिद्धत्वात् षकारान्तस्य स्वरूपस्य ग्राहको भविष्यतीत्यर्थः ॥

(उद्द्योतः) डकारान्त इति । षष उत्तरयोर्जश्शसोरिति स्वरूपग्रहणेन लुकि कार्ये जश्त्वमसिद्धमिति भावः ॥ तथापि संज्ञासूत्रे टान्तोच्चारणात्षड्भ्य इत्यादौ चर्त्वासिद्धत्वेनैव निर्वाहः । संहितापाठेन डान्तस्य संज्ञात्वे षड्चतुर्भ्यं इत्यत्र चर्त्वासिद्धत्वमावश्यकमिति तात्पर्यम् ॥

(प्रयोजनभाष्यम्)

मन्त्राद्यर्थं तर्हीदं वक्तव्यम् । मन्त्रे-ऋचि-यजुषीति यदुच्यते, तन्मन्त्रशब्दे-ऋक्शब्दे-यजुःशब्दे च मा भूत् ॥

(प्रदीपः) मन्त्राद्यर्थमिति । मन्त्रादयः शब्दस्य संज्ञाः ॥

(उद्द्योतः) ष्णान्तेत्यादिज्ञापकं शास्त्रीयशब्दसंज्ञायां न स्वरूपग्रहणमित्यर्थं बोधयितुं न तु शब्दपदार्थके- इत्याशयेनाह-भाष्ये—मन्त्राद्यर्थमिति ॥

(प्रयोजननिराकरणे भाष्यवार्तिकम् ॥)

॥ मन्त्राद्यर्थमिति चेच्छास्त्रसामर्थ्यादर्थगतेः सिद्धम् ॥

(भाष्यम्)

मन्त्राद्यर्थमिति चेत् । तन्न ।

किं कारणम् ?

शास्त्रस्य सामर्थ्यादर्थस्य गतिर्भविष्यति । मन्त्रे-ऋचि-यजुषीति यदुच्यते, मन्त्रशब्दे ऋक्शब्दे यजुष्शब्दे च तस्य कार्यस्य संभवो नास्तीति कृत्वा मन्त्रादिसहचरितो योऽर्थस्तस्य गतिर्भविष्यति, शास्त्रार्थात् ॥

(प्रदीपः) शास्त्रसामर्थ्यादिति । देवसुम्नयोरित्यादौ क्यजादीनां निमित्तत्वेनोपादानाद्यजुषि ऋचि मन्त्र इति च स्वरूपं न ग्रहीष्यते । न हि तथाविधलक्ष्यमस्तीति भावः ॥

मन्त्रादिसहचरित इति । साहचर्यं च शब्दानुविद्धस्यैवार्थस्यावगमकम् ॥

(उद्द्योतः) शब्दानुविद्धस्यैवेति । न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते-इति पर्युक्तेरिति भावः ॥ तद्बोध्यत्वेन सहचरितत्वमित्यन्ये ॥

(न्यूनतानिराकरणम्)

(३८६ आक्षेपवार्तिकम् ॥ ५ ॥)

॥ * ॥ सित्तद्विशेषाणां वृक्षाद्यर्थम् ॥ * ॥

(भाष्यम्)

सिन्निर्देशः कर्तव्यः । ततो वक्तव्यम्—'तद्विशेषाणां' ग्रहणं भवति—इति ॥

किं प्रयोजनम् ?

'वृक्षाद्यर्थम् ।' "विभाषा वृक्षमृग—" इति । प्लक्षन्यग्रोधं, प्लक्षन्यग्रोधाः ॥

(प्रदीपः) सित्तद्विशेषाणामिति । 'वृक्षमृगस्' इत्येवं निर्देशः कर्तव्यः । एतदपि न्यायसिद्धं, तुल्यजातीयानां द्वन्द्व एकवद्भवतीति वक्ष्यते । पर्यायाणां च युगपत्प्रयोगाभावात् सामान्यविशेषाणां च चार्थाभावात् सामान्यशब्देन सर्वविशेषाणामाक्षेपात् 'धववृक्षं' इति द्वन्द्वाभावाद्विशेषाणामेव प्लक्षन्यग्रोधादीनां ग्रहणं सिद्धम् ॥

(उद्द्योतः) चार्थाभावमुपपादयति—सामान्यशब्देनेति । एवंच पदार्थभेदाभावात्साहित्यरूपचार्थासंभव इति भावः ॥

(३८७ आक्षेपवार्तिकम् ॥ ६ ॥)

॥ * ॥ पित्पर्यायवचनस्य च स्वाद्यर्थम् ॥ * ॥

(भाष्यम्)

पिन्निर्देशः कर्तव्यः । ततो वक्तव्यम्—'पर्यायवचनस्य ।' तद्विशेषाणां च ग्रहणं भवति स्वस्य च रूपस्येति ॥

किं प्रयोजनम् ?

'स्वाद्यर्थम् ।' "स्वे पुषः"—स्वपोषं पुष्यति, रैपोषम्, धनपोषम्, विद्यापोषम्, अश्वपोषम्, गोपोषम् ॥

(प्रदीपः) पित्पर्यायवचनस्य चेति । चशब्दात् स्वरूपस्य विशेषाणां च ग्रहणम् । इदं वाचनिकमेव ॥

(३८८ आक्षेपवार्तिकम् ॥ ७ ॥)

॥ * ॥ जित्पर्यायवचनस्यैव राजाद्यर्थम् ॥ * ॥

(भाष्यम्)

जिन्निर्देशः कर्तव्यः । ततो वक्तव्यम्—'पर्यायवचनस्यैव' ग्रहणं भवति ॥

किं प्रयोजनम् ?

'राजाद्यर्थम् ।' "सभा राजाऽमनुष्यपूर्वा"-इनसभम्, ईश्वरसभम् ॥ तस्यैव न भवति—राजसभा ॥ तद्विशेषाणां च न भवति—पुष्पमित्रसभा, चन्द्रगुप्तसभा ॥

(प्रदीपः) जित्पर्यायेति । इदं न्यायसिद्धमित्याहुः । 'अराजा' इति पर्युदास आश्रीयते । तेन राजशब्दसदृशानां तत्पर्यायाणामेव ग्रहणं सिध्यति ॥

(उद्द्योतः) पर्युदास इति । कश्चित्तु अराजेति छेदाभावात् । किंच राजशब्दः शब्दपरः, मनुष्यशब्दश्चार्थपर इति दुर्लभं स्यात् । किंच एवं अमनुष्यशब्देनापि मनुष्यपर्यायाणामेव ग्रहणं स्यादितीदं वाचनिकमेवेत्याह ॥

(३८९ आक्षेपवार्तिकम् ॥ ८ ॥)

॥ * ॥ झित्तस्य च तद्विशेषाणां च मत्स्याद्यर्थम् ॥ * ॥

(भाष्यम्)

झिन्निर्देशः कर्तव्यः । ततो वक्तव्यम्—'तस्य च तद्विशेषाणां च' ग्रहणं भवति—इति ॥

किं प्रयोजनम् ?

'मत्स्याद्यर्थम्' । "पक्षिमत्स्यमृगान् हन्ति"—मात्स्यिकः । तद्विशेषाणाम्—शाफरिकः, शाकुलिकः । पर्यायवचनानां न भवति—अजिह्मान् हन्ति, अनिमिषान् हन्ति ॥

(भाष्येष्टिः)

अस्यैकस्य पर्यायवचनस्येष्यते ।

मीनान् हन्ति-मैनिकः ॥

स्वं रूपं शब्दस्याशब्दसंज्ञा ॥ ६८ ॥

(प्रदीपः) झित्तस्य चेति । इदं वाचनिकमेव ॥ मत्स्याद्यर्थमिति । मृगपक्षिणोस्तु पिन्निर्देशस्तत्फललाभार्थं कर्तव्यः ॥ अस्यैकस्येति । इयमिष्टिरेव ॥ ६८ ॥

(उद्द्योतः) भाष्यन्तौ विहाय मध्योपादानेऽभिप्रायमाह—मृगेति । एवंच मत्स्याद्यर्थमित्यादिशब्दप्रयोजनं चिन्त्यम् ॥ ६८ ॥

(१३ ग्रहणकशास्त्रम् ॥ १ । १ । ९ आ. ९ सू. ॥)

अणुदित्सवर्णस्य चाप्रत्ययः ॥ १ । १ । ६९ ॥

(भाव्यमानेनेतिपरिभाषाज्ञापनम्)

(जिज्ञासाभाष्यम्)

अप्रत्यय इति किमर्थम् ?

(प्रदीपः) अणुदित्० ॥ ६९ ॥ अप्रत्यय इति किमर्थमिति । किं यस्य प्रत्ययसंज्ञा विहिता तस्य प्रतिषेधः, उत यः

प्रतीयते=विधीयत इति यौगिकः प्रत्ययस्तस्यापीति **प्रश्नः** ॥

(**उद्योतः**) **अणुदित्०** ॥ ६९ ॥ **किं यस्येति** । नाक्षेपोऽयम्, किंतु विशेषजिज्ञासेत्यर्थः । उत यौगिक इत्यन्वयः । **किमर्थ-** मित्यत्रार्थशब्दोऽभिधेयपर इति तात्पर्यम् ॥

(**समाधानभाष्यम्**)

"सनाशंसभिक्ष उः" "अ सांप्रतिके" ॥

(**आक्षेपभाष्यम्**)

अत्यल्पमिदमुच्यते—अप्रत्यय इति । "अप्रत्ययादेशटित्किन्मितः" इति वक्तव्यम् ॥ प्रत्यये—उदाहृतम् ॥ आदेशे—"इदम इश्" इतः, इह ॥ टिति—लविता, लवितुम् ॥ किति—बभूव ॥ मिति—हे अनड्वन् ॥

(**प्रदीपः**) **इत इति** । विशेषविहितत्वात् त्यदाद्यत्वं बाधित्वा त्रिमात्र आदेशः प्राप्नोति ॥ **बभूवेति** । अनुनासिकः प्राप्नोति ॥ **अनड्वन्निति** । आमपि पक्षे प्राप्नोति ॥

(**उद्योतः**) नन्विदमः परत्वात् त्यदाद्यत्वेऽन्तरङ्गत्वाच्च पररूपेऽर्धतृतीयमात्रस्य सवर्णग्रहणेऽपि नान्तरतम आदेशः संभवतीति श्रुत एव भविष्यति । **न च** श्रुतापेक्षया दीर्घप्लुतयोरन्तरतमत्वात्ते एव भविष्यतः, ह्रस्वोच्चारणं तु लाघवार्थं स्याद् इति **वाच्यम्** । एवं तर्हि परत्वाद्धलि लोपे मात्रिकत्वान्मात्रिक एव भविष्यति । तत्र न 'आपि' इति वर्तते, फलाभावादत आह—**विशेषेति** । येन नाप्राप्तिन्यायादिति भावः । शादीनां चोपदेशे एवेत्संज्ञालोपयोरणत्वेन सवर्णग्रहणप्रसक्तिः ॥ **अनुनासिक इति** । पक्षे-इति शेषः ॥

(**टिद्ग्रहणवैयर्थ्यसाधकभाष्यम्**)

टितः परिहारः—आचार्यप्रवृत्तिर्ज्ञापयति—'न टिता सवर्णानां ग्रहणं भवति' इति । यदयम्—ग्रहोऽलिटि दीर्घत्वं शास्ति ॥

(**प्रदीपः**) **यदयमिति** । ग्रहेरेव दीर्घो नान्येभ्य इति नियमाभावादिति भावः ॥

(**उद्योतः**) नियमार्थं तत् स्यात्, अत आह—**ग्रहेरेवेति** । वृतो वेत्यनेन विरोधादिति भाव इति केचित् ॥ वस्तुतस्तु यथा दिक्सङ्ख्ये इति नियमादप्राप्तसमासविधायकं **तद्धितार्थेति**, एवं ग्रहेरेवेति नियमादप्राप्तदीर्घविध्यर्थं **वृतो** वेति स्यादिति चिन्त्यैषा व्याख्या । तस्माद्विधेयसङ्कोचस्यान्याय्यत्वान्न तथा नियम इति भावः ॥

(**ज्ञापकत्वनिराकरणभाष्यम्**)

नैतदस्तिज्ञापकम् । नियमार्थमेतत् स्यात्—ग्रहः अलिटि दीर्घ एवेति ॥

(**प्रदीपः**) **नियमार्थमिति** । ग्रहेर्दीर्घ एव, न ह्रस्व इत्येवमर्थं स्यादित्यर्थः ॥

(**ज्ञापकान्तरभाष्यम्**)

यत्तर्हि "वृतो वा" इति विभाषां शास्ति ॥

(**प्रदीपः**) **वृतो वेति** । ननु ववरिथेति लिटि दीर्घो मा भूदित्येवमर्थमेतत् स्यादिति कथं ज्ञापकम् ॥ एवं तर्हि 'वृतः-' इत्यत्रापि अलिटीत्यनुवर्तनाल्लिटि दीर्घनिषेधादन्यत्र उभयस्मिन् सिद्धे वाग्रहणं ज्ञापकम्—ईट इटा ग्रहणाभावस्य ॥

(**उद्योतः**) **ववरिथेति** । 'ववर्थ' इति छन्दसि इडभावनिपातनाद् भाषायां क्रृसृभृवृस्तुद्रुस्रुश्रुवति इट्प्रतिषेधो न । अलिटीत्यत्र वृतो वेत्यर्थाद् लिटि ह्रस्व एवेति भावः ॥ **वाग्रहणमिति** । अत एव भाष्ये—**यद्विभाषां शास्तीत्युक्तम्** ॥

(**यौगिकत्वे पर्युदासवैयर्थ्यभाष्यम्**)

सर्वेषामेष परिहारः—

'भाव्यमानेन सवर्णानां ग्रहणं न'

इत्येवं न भविष्यति ॥

(**उद्योतः**) भाष्ये—**भाव्यमानेनेति** । इयं च जातिग्रहणप्राप्तं गुणाभेदकत्वप्राप्तं चानण्त्साधारण्येन प्राप्तं सवर्णग्रहणं वारयितुमावश्यकीति भावः ॥

(**संज्ञापरत्वेऽपि पर्युदासवैयर्थ्यभाष्यम्**)

प्रत्यये भूयान् परिहारः—अनभिधानात्प्रत्ययः सवर्णान् न ग्रहीष्यति । यान् हि प्रत्ययः सवर्णग्रहणेन गृह्णीयात् न तैरर्थस्याभिधानं स्यात् । अनभिधानान्न भविष्यति ॥

(**प्रदीपः**) **प्रत्यये भूयानिति** । साधारणश्चासाधारणश्चेत्यर्थः । 'प्रत्ययः' इत्यन्वर्थसंज्ञा कृता-येनार्थं प्रतियन्ति स प्रत्ययः । न च दीर्घप्लुतयोरर्थस्याभिधानमस्ति ॥

(**उद्योतः**) **साधारणश्चेति** । भूयानित्युक्तिर्नापूर्वोऽनेकसमाधानाभिप्राया, किंतु सूत्रोक्ताप्रत्ययग्रहणमपेक्ष्य-इति **'भूयान्'** इति प्रतिज्ञायैकपरिहारोपन्यासेऽपि न विरोध इति भावः ॥ **नन्वस्य** **एवा**वित्यादावेवार्थाभिधानासमर्थस्यापि सवर्णस्य ग्रहणं स्यादत **आह—प्रत्यय इतीति** । प्रत्ययविधौ सवर्णग्रहणे हि तेषामपि प्रत्ययत्वमेष्टव्यम् । तच्चान्वर्थत्वादसंभवीति न तत्र सवर्णग्रहणमिति भावः ॥

(**प्रयोजनभाष्यम्**)

इदं तर्हि प्रयोजनम्—इह केचित्प्रतीयन्ते, केचित्प्रत्याय्यन्ते । ह्रस्वाः प्रतीयन्ते, दीर्घाः प्रत्याय्यन्ते । यावद्ब्रूयात्—प्रत्याय्यमानेन सवर्णानां ग्रहणं नेति, तावदप्रत्यय इति ॥

(**प्रदीपः**) **ह्रस्वा इति** । श्रूयन्ते—उच्चार्यन्ते अगादिचोदनाखित्यर्थः ॥ **दीर्घा इति** । ह्रस्वैर्गृहीतैरण्त्वाद्दीर्घाणां ग्रहणात् । **तत्राद्यन आ विभक्ता**वित्यत्राकारो ग्राहको मा भूदित्यर्थः । यथैव हि अण्त्वादाकारो रपरत्वादिकार्यं प्रतिपद्यते, तथा ग्राहकत्वमपि प्रतिपद्येतेति भावः ॥ कथं पुनरप्रत्यय इत्यस्याप्रत्याय्यमान इत्यर्थः ? अन्तर्भावितण्यर्थादितेः कर्मण्यज्विधानात् ॥

(**उद्योतः**) **उच्चार्यन्त इति** । उच्चारणं चात्र साक्षाच्छब्देन बोधनं विवक्षितम् । अतोऽणादिशब्दप्रतीयमानेकारादिभिः सवर्णानां ग्रहणं सिद्धम् ॥ **ह्रस्वैर्गृहीतैरिति** । प्रकृतसूत्रस्थाण्पदेनेति शेषः ॥ ननु प्रत्याहारस्थत्रोपदिष्टा एवाण इति कथमाकारो ग्राहक इत्यत आह—**यथैवेति** । न चाक्षरसमाम्नायिकविषयकः प्रतिषेधः, प्रत्याय्यमानविषयं तु सवर्णग्रहणमिति वैपरीत्यं किं न स्यादिति **वाच्यम्** । तथा सत्यको विधीयमानस्य पूर्वसवर्णदीर्घस्य कुमार्यावित्यादावप्राप्तेः

'दीर्घाज्जसि च' इति प्रतिषेधोऽनर्थकः स्यादिति भावः ॥ एवं च वर्णसमाम्नायपठितानामेव ग्राहकत्वबोधनार्थमप्रत्ययपदमिति तात्पर्यम् ॥

(आक्षेपभाष्यम्)

कं पुनर्दीर्घः सवर्णग्रहणेन गृह्णीयात्?

(प्रयोजनसाधकभाष्यम्)

ह्रस्वम् ॥

(प्रयोजननिराकरणभाष्यम्)

यत्नाधिक्यान्न ग्रहीष्यति ॥

(प्रदीपः) यत्नाधिक्यादिति । ननु च ह्रस्वोच्चारणे अर्धमात्रिकस्य मात्रिक एव स्यादिति दीर्घोच्चारणमुभयार्थं स्यात् । एतत्तु न निरूपितम् ॥ न्याय्य एवात्र परिहारो विधास्यते ॥

(उद्योतः) उभयार्थम्-ह्रस्वदीर्घोभयविध्यर्थम् । एवंच यत्नाधिक्यमेवासिद्धमिति भावः ॥ न्याय्य एवेति । 'अनण्त्वाद' इत्ययमित्यर्थः ॥

(प्रयोजनसाधकभाष्यम्)

प्लुतं तर्हि गृह्णीयात् ॥

(प्रयोजननिराकरणभाष्यम्)

अनण्त्वान्न ग्रहीष्यति ॥

(प्रदीपः) अनण्त्वादिति । अत्र हि सूत्रे प्रत्याहारसन्निविष्टा एव गृह्यन्ते, स्वात्मनि क्रियाविरोधात्, अनिष्पादात्, ग्रहणकशास्त्रान्तराभावाच्च । अत्र सूत्रे अकारादिभिराकारादीनां ग्रहणासम्भवः । अन्येषु तु प्रदेशेषु अनेन सूत्रेणाकारादिभिराकारादयो गृह्यमाणा अणादिकार्याणि लभन्ते ॥

(उद्योतः) यदुक्तं-यथैवेति, तत्राह—अत्र हीति । स्वात्मनि क्रिया-स्वस्मिन्प्रवृत्तिः ॥ विरोधे हेतुमाह—अनिष्पादादिति । अर्थाबोधादित्यर्थः ॥

(सिद्धान्तप्रयोजनभाष्यम्)

एवं तर्हि सिद्धे सति यत् 'अप्रत्ययः' इति प्रतिषेधं शास्ति, तज्ज्ञापयत्याचार्यः—भवत्येषा परिभाषा—

'भाव्यमानेन सवर्णानां ग्रहणं न'

इति ॥

(प्रदीपः) भाव्यमानेनेति । प्रतीयते=विधीयत इति यौगिकस्यात्र प्रत्ययस्य ग्रहणमिति भावः ॥

(उद्योतः) नन्वल्पविषयेणाप्रत्यय इत्यनेन कथं बहुविषयपरिभाषार्थः शक्यते प्रतिपादयितुमत आह—प्रतीयत इति । भाष्ये—ज्ञापयतीत्यस्य योगेन बोधयतीत्यर्थः ॥ अप्रत्यय इति च वाक्यभेदेन निषेधार्थम् । अणित्यस्य च नात्र संबन्धः । तेनोक्तसकलार्थलाभ इति भावः ॥ वस्तुत एकदेशानुमतिद्वारा तां परिभाषां ज्ञापयतीति भाष्याक्षरार्थः ॥ 'विधीयते' इत्यर्थे 'प्रतीयते' इत्यस्य प्रयोगाद्दृष्ट्या कैयटोक्तं चिन्त्यम् ॥

(अण्ग्रहणप्रयोजनम्)

(आक्षेपभाष्यम्)

किमर्थं पुनरिदमुच्यते?

(प्रदीपः) किमर्थं पुनरिति । आकृतिनिर्देशात् सिद्धमिति प्रश्नः ॥

(उद्योतः) आकृतीति । प्रत्याहारसूत्रेषु, अस्यच्वावित्यादिषु चेत्यर्थः ॥

(३९० समाधानवार्तिकम् ॥ १ ॥)

॥ * ॥ अण् सवर्णस्येति स्वरानुनासिक्यकालभेदात् ॥ * ॥

(भाष्यम्)

अण् सवर्णस्येत्युच्यते । स्वरभेदादानुनासिक्यभेदात् कालभेदाच्चाण् सवर्णान्न गृह्णीयात् । इष्यते च—सवर्णे ग्रहणं स्यादिति । तच्चान्तरेण यत्नं न सिध्यतीति ॥ एवमर्थमिदमुच्यते ॥

(प्रदीपः) अण् सवर्णस्येति । उदिद्ग्रहणस्याविचारयिष्यमाणत्वादेवमुक्तम् । व्यक्तिनिर्देशे कालादिभिन्नस्य ग्रहणं न प्राप्नोतीति भावः ॥

(उद्योतः) नेयमुदिद्विषया शङ्का, चुत्वादिजातौ मानाभावेन तस्यावश्यकत्वादित्याशयेनाह—उदिदिति ॥ कालादिभिन्नस्येति । एकोऽवर्णः, उदात्तत्वादिकं ध्वनिगतमिति पक्षेऽपि उपाधिभेदभिन्नत्वाद् ग्रहणं न सिध्यतीति भावः ॥ अनन्ता अवर्णव्यक्तय इति पक्षे तु अग्रहणं स्पष्टमेवेति बोध्यम् ॥

(भाष्यम्)

अस्ति प्रयोजनमेतत् ॥

किं तर्हीति?

(३९१ आक्षेपवार्तिकम् ॥ २ ॥)

॥ * ॥ तत्र प्रत्याहारग्रहणे सवर्णाग्रहणमनुपदेशात् ॥ * ॥

(भाष्यम्)

तत्र प्रत्याहारग्रहणे सवर्णानां ग्रहणं न प्राप्नोति—"अकः सवर्णे दीर्घः" इति ॥

किं कारणम्?

'अनुपदेशात् ।' यथाजातीयकानां संज्ञा कृता तथाजातीयकानां संप्रत्यायिका स्यात् । ह्रस्वानां च क्रियते । ह्रस्वानामेव संप्रत्यायिका स्यात्, दीर्घाणां न स्यात् ॥

(प्रदीपः) प्रत्याहारग्रहण इति । अकोऽचीति यत्र संज्ञया प्रत्यायनमिकारादीनां तत्र तैरन्येषां ग्रहणं न स्यात् । यत्र स्वरूपेणोच्चार्यते—'अस्य च्वौ' 'यस्येति च' इति, तत्रैवैषां ग्राहकत्वं स्यात् ॥ अनुपदेशादिति । अनुच्चारणादित्यर्थः । न हि प्रत्याहारे दीर्घा उच्चारिताः, यतोऽगादिचोदनाभिर्गृह्येरन् ॥ अथवा—अकोऽचीत्यादावनुच्चारिता इकारादयो दीर्घाणां प्रत्यायका न स्युरित्यर्थः ॥

(उद्योतः) नन्वेतत्प्रयोजनं-अस्य च्वावित्यादौ वा, अगादिप्रत्याहारेषु वा । तत्राद्यं तत्रानुवृत्तिनिर्देशे इत्यादिना दूषयि-

ष्यति । नान्त्य इत्याह—प्रत्याहारग्रहणे इत्यादि । प्रत्याहारग्रहणे सवर्णाग्रहणमिति वार्तिकस्य द्वेधाऽर्थः—अक इत्यादौ ईकारादीनामगादिसंज्ञाभिर्ग्रहणं न प्राप्नोति, अनुपदेशात्-अक्षरसमाम्नाये तेषामनुच्चारणादित्यर्थः । तदाह—यत्र संज्ञयेति । एकस्यैव युगपत्प्रत्याय्यत्वप्रत्यायकत्वयोर्विरोधादित्यर्थः ॥ यत्र स्वरूपेणेति । इदं चिन्त्यम्, व्यक्त्यानन्त्ये तस्याणत्वाभावात् । तस्मादः स्वरूपेणोच्चार्यते अक इत्यादावकारादिस्तस्यैव ग्राहकत्वं स्यादिति वक्तुमुचितम् ॥ प्रत्याहारे-अइउणित्यादौ ॥ भाष्ये—यथाजातीयकानामिति । वर्णसमाम्नायपठितानामित्यर्थः ॥ संज्ञेति । आदिरन्त्येनेति कृतागादिसंज्ञेत्यर्थः ॥ यद्वा—अगादौ इकारादिभिर्ह्रस्वैर्दीर्घाणामग्रहणम् । कुतः ? अनुपदेशात्-अकोऽचीत्यादाविकारादीनामनुच्चारणादित्यर्थः, तदाह—अथवेति । भाष्यस्वारस्यं त्वाद्यव्याख्यायामेव ॥

(आक्षेपबाधकभाष्यम्)

ननु च ह्रस्वाः प्रतीयमाना दीर्घान् संप्रत्याययिष्यन्ति ॥

(प्रदीपः) **ननु चेति** । उच्चार्यमाणैरेव प्रत्यायकैर्भवितव्यमिति नास्ति । सन्निहितास्तु प्रत्यायकाः । तच्च सन्निधानं यथायोगमस्त्येवेत्यर्थः ॥

(उद्योतः) **उच्चार्यमाणैरेवेति** । पुस्तकदर्शनादौ व्यभिचारादित्यर्थः ॥ **सन्निहिता इति** । बुद्धिसंनिहिता इत्यर्थः ॥ अयं भावः—शब्दा उपस्थिता बोधं जनयन्ति । उपस्थितिस्तु-स्मृतिरूपा प्रत्यक्षरूपा च । न त्वन्त्यैवेति नियमः, लिपिस्मारितपदैर्बोधानापत्तेरिति ॥ **संनिधानमिति** । प्रतीतिरित्यर्थः ॥ **यथायोगम्**—उच्चारणेन संज्ञया चेत्यर्थः ॥

(३९२ आक्षेपसाधकवार्तिकम् ॥ ३ ॥)

॥ * ॥ ह्रस्वसंप्रत्ययादिति चेदुच्चार्यमाणशब्दसंप्रत्यायकत्वाच्छब्दस्यावचनम् ॥ * ॥

(भाष्यम्)

ह्रस्वसंप्रत्ययादिति चेत् । तन्न ।

किं कारणम् ?

उच्चार्यमाणः शब्दः संप्रत्यायको भवति, न संप्रतीयमानः । तद्यथा—ऋगित्युक्ते संपाठमात्रं गम्यते, नास्या अर्थो गम्यते ॥

(प्रदीपः) **उच्चार्यमाणेति** । प्रतीयमानो हि प्रधानं कथमन्यप्रत्यायनेऽङ्गभावं तदैव गच्छेदित्यर्थः ॥ **शब्दस्यावचनमिति** । प्रतीयमानेन शब्देनान्यस्याप्रत्यायनमित्यर्थः ॥ **ऋगित्युक्त इति** । यद्यपि प्रकरणवशाद्विशिष्टसन्निवेशाऽपि ऋक्शब्देन ऋक् प्रत्याय्यते, तथापि सा स्वार्थं न प्रत्याययतीत्यर्थः ॥

(उद्योतः) **प्रतीयमानो हीति** । यद्यप्युच्चारणे प्रधानमपि अर्थप्रतीतावङ्गभावं प्रतिपद्यते, तथाप्युच्चारणकृतायास्तत्तत्प्रतिबिम्बविशिष्टस्फोटाभिव्यक्तेश्चिरस्थायितयोपपद्यते तत्त्वम् ; शब्दज्ञानमात्रस्य तु न तदभिव्यञ्जकत्वं, वक्ष्यमाणहेतोरिति भावः ॥ **अन्यस्येति** । दीर्घादिरूपशब्दस्येत्यर्थः ॥ भाष्ये—**ह्रस्वसंप्रत्ययादिति** । तृतीयातत्पुरुषः ॥ **ऋगित्युक्ते संपाठमात्रं गम्यते इति** । एतेनोच्चारितानामेव प्रत्यायकत्वे रहसि पुस्तकमीक्षमाणस्य बोधानापत्तेर्वाचकज्ञानसामान्यस्यैव बोधे तन्त्रत्वेनेदमयुक्तमित्यपास्तम् । मानसजपस्थल इव तत्रापि स्वीयसूक्ष्मोच्चारणाद्बोधेनाक्षतेः । जपे हि मन्त्राणां त्रैस्वर्यमेव, तत्तत्स्थानेषु उच्चादिदेशोपलभ्यमानत्वरूपोदात्तत्वादेर्मात्राकालिकत्वादिरूपह्रस्वत्वादेश्च विनोच्चारणमनभिव्यक्तेः । यद्वा—लिपेरेव चेष्टादिवत्सङ्केतेन बोधकत्वम् । अत एव लिपौ शब्दत्वभ्रमो बालानाम् । यद्वा—लिपावनादेः शब्दतादात्म्याध्यासाद्बोधकत्वम् । लिपौ शब्दत्वबाधज्ञानवतां पण्डितानामपि अन्तःकरणादावात्मत्वप्रत्यये भ्रमत्वं जानतामनादिसिद्धारोपेणैव व्यवहारवत् बोधोऽपि ॥ ननु ऋगित्युक्ते तद्विशेषाप्रतीतेरर्थप्रतीतिसंभावनाया अप्यभावः, ऋक्त्वस्य वेदत्वस्य चार्थप्रतीतिजनकतानवच्छेदकत्वात्-अत आह—**यद्यपीति**। ऋक्शब्देन विशिष्टसंनिवेशाऽपि ऋक् प्रत्याय्यत इत्यन्वयः । यत्र सङ्केतादिग्रहाद् ऋगित्युक्ते अग्निमीले पुरोहितमित्याद्यानुपूर्वीप्रकारेण बोधस्तत्रापि सा स्वार्थं वेदनादिक्रियाकर्मत्वेन न प्रत्याययतीति भावः ॥

(समाधानभाष्यम्)

एवं तर्हि वर्णपाठ एवोपदेशः करिष्यते ॥

(प्रदीपः) **एवं तर्हीति** । 'अइउ' इति प्रत्याहार एवाकारादिभिराकारादीनां ग्रहणात् तेषामप्यगादिभिः संज्ञाभिर्ग्रहणं भविष्यतीत्यर्थः ॥ **उपदेश इति** । प्रत्यायनमित्यर्थः ॥ **करिष्यत इति** । व्याख्यास्यते ॥

(उद्योतः) **प्रत्यायनमिति** । तच्चैतत्सूत्रेणैवेति बोध्यम् ॥

(३९३ समाधानबाधकवार्तिकम् ॥ ४ ॥)

॥ * ॥ वर्णपाठ उपदेश इति चेदवरकालत्वात् परिभाषाया अनुपदेशः ॥ * ॥

(भाष्यम्)

वर्णपाठक्रम उपदेश इति चेदवरकालत्वात् परिभाषाया अनुपदेशः ॥

(प्रदीपः) **अवरकालत्वादिति** । निष्पन्नेष्वक्ष्वनयाऽन्यथास्य च्वावित्यादौ सवर्णानां ग्रहणं भवति, नाक्षेषु नापि स्वात्मनि, अनिष्पन्नत्वादिति भावः ॥

(उद्योतः) अनेन तत्प्रत्यायनमशक्यमित्याह—भाष्ये—**अवरकालत्वादिति** ॥

(आक्षेपभाष्यम्)

किं परा सूत्रात् क्रियत इत्यतोऽवरकाला ?

(उद्योतः) **परा सूत्रादिति** । सूत्रात्-प्रत्याहारसूत्रात्परा-परकाला क्रियत इत्यर्थः ॥ तेषामनादित्वात्, एषां पाणिनिकृतत्वादिति भावः ॥

(समाधानभाष्यम्)

नेत्याह । सर्वथाऽवरकालैव । वर्णानामुपदेशस्तावत् । उपदेशोत्तरकाला-इत्संज्ञा । इत्संज्ञोत्तरकालः-"आदिरन्त्येन सहेता" इति प्रत्याहारः । प्रत्याहारोत्तरकाला-सवर्णसंज्ञा ॥ सवर्णसंज्ञोत्तरकालम्—

"अणुदित्सवर्णस्य चाप्रत्ययः" इति। सैषा उपदेशोत्तरकाला-अवरकाला सती वर्णानामुत्पत्तौ निमित्तत्वाय प्रकल्पयिष्यत इत्येतन्न ॥

(प्रदीपः) सर्वथेति । आर्थक्रमेणापि, न शब्दक्रमेणैवेत्यर्थः ॥ वर्णानामुत्पत्ताविति । अइउणित्यत्र इयमेव वर्णानाकारादीनुत्पादयतीत्येतन्नास्ति ॥

(उद्योतः) अवरकालैवेति । वाक्यार्थज्ञाने पदार्थज्ञानस्य कारणत्वादिति भावः ॥ शाब्दक्रमः-अष्टाध्यायीक्रमः ॥ प्रत्याहारोत्तरकाला सवर्णसंज्ञेति । नाज्झलावित्येतद्विषयनिर्णयोत्तरं तत्परिहारेण सवर्णपदशक्तिग्रहस्यैव व्यवहारोपयोगित्वादिति भावः ॥ वर्णानामुत्पत्ताविति । प्रतीतावित्यर्थः ॥ अक इत्यादावाद्यवर्णव्यक्त्या एव प्रत्यायकत्वादध्याहारेण व्याचष्टे—अइउणिति ॥ उत्पादयतीति । प्रत्याययतीत्यर्थः ॥

(३१४ समाधानबाधकवार्तिकम् ॥ ५ ॥)

॥ * ॥ तस्मादुपदेशः ॥ * ॥

(भाष्यम्)

तस्मादुपदेशः कर्तव्यः ॥

(प्रदीपः) तस्मादिति । प्रत्याहार एव दीर्घप्लुता अपि पठनीया इत्यर्थः ॥

(उद्योतः) प्रत्याहारे-अइउणित्यादौ ॥ न च प्रत्याहारेषु तद्बाच्यवाच्ये लक्षणाऽङ्गीकारान्न दोषः । उक्तभाष्यरीत्या तद्बाच्यानां प्रत्यायकत्वाभावेन तेषामशक्तत्वेन लक्ष्यतावच्छेदकलक्षणामूलसंबन्धज्ञानयोर्दुरुपपादत्वात् ॥

(अण्ग्रहणप्रत्याख्यानम्)

(३१५ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ तत्रानुवृत्तिनिर्देशे सवर्णाग्रहणमनण्त्वात् ॥ * ॥

(भाष्यम्)

तत्रानुवृत्तिनिर्देशे सवर्णानां ग्रहणं न प्राप्नोति—"अस्य च्वौ" "यस्येति च" ॥

किं कारणम् ?

'अनण्त्वात्' । न ह्येतेऽणः, येऽनुवृत्तिनिर्देशे ॥

के तर्हि ?

येऽक्षरसमाम्नाय उपदिश्यन्ते ॥

(प्रदीपः) तत्रानुवृत्तीति । व्यक्तिपक्षे सत्यपि सूत्रारम्भेऽवान्तरभेदसंभवात् ग्रहणं न सिद्ध्यतीत्यर्थः ॥

(उद्योतः) एवं प्रत्याहारेषु सूत्रप्रयोजनाभावमुक्त्वा अस्य च्वावित्यादावपि तमाह—तत्रानुवृत्तिनिर्देश इति । भाष्ये-वृत्ति-वर्णसमाम्नायमनुगतस्तत्सदृशोऽनुवृत्तिरकारादिस्तस्य निर्देशः-स्वरूपेणोच्चारणमित्यर्थः ॥ तत्र सवर्णाग्रहणे हेतुमाह—व्यक्तीति । अनन्ता व्यक्तय इति पक्षे इत्यर्थः ॥ तदाह—अवान्तरभेदेति । जात्येकत्वेऽपि व्यक्तीनां परस्परं भेदसंभवादित्यर्थः ॥ एका अवर्णव्यक्तिरिति पक्षे तु यद्यपि सिध्यति, तथापि सोऽसङ्गतः, उदात्तादिविरुद्धधर्माध्यासात् । यदि तु ध्वनिनिष्ठास्ते, तदा कत्वखत्वादिकमपि तन्निष्ठमस्तु; किं वर्णैः ? नो चेदनन्ता एवेति भावः ॥

(आक्षेपबाधकभाष्यम्)

एवं तर्हि-अनण्त्वादनुवृत्तौ न, अनुपदेशाच्च प्रत्याहारे न । उच्यते चेदम्—अण् सवर्णान् गृह्णाति—इति वचनाद्भविष्यति ॥

(प्रदीपः) वचनादिति । अण्सदृशोऽणिति ग्रहीष्यत इत्यर्थः ॥

(उद्योतः) अनणो वचनादपि कथं ग्राहकत्वमत आह—अण्सदृश इति ॥

(आक्षेपसाधकं श्लोकवार्तिकम्)

॥ वचनाद्यत्र तन्नास्ति ॥

(भाष्यम्)

नेदं वचनाल्लभ्यम् । अस्ति ह्यन्यदेतस्य वचने प्रयोजनम् ॥

किम् ?

य एते प्रत्याहाराणामादितो वर्णास्तैः सवर्णानां ग्रहणं यथा स्यात् ॥

(प्रदीपः) यत्रेति । अनन्तरोक्तमुभयं यत्र नास्ति-अकोऽचीत्यादौ । अत्र ह्यनुबन्धेन चिह्नेन प्रत्याहारस्थ एव निर्दिष्ट इत्यणत्वमुच्चारणं चास्ति । तत्राकार उच्चारित आदिरन्त्येन सहेतेति मध्यपातितानां स्वरूपस्य च ग्राहकः, अस्माच्च वचनात्सवर्णानामपीत्यर्थः । एवं व्यक्तिपक्षे सत्यपि सूत्रारम्भे नास्तीष्टसिद्धिः ॥

(उद्योतः) उभयम्-अनणत्वमनुच्चारणं च ॥ मध्यपातितानामिति । दृष्टान्तार्थम् ॥

(समाधानान्तरभाष्यम्)

एवं तर्हि—

(३१६ सिद्धान्तसमाधानअणूप्रत्याख्यानवार्तिकम् ॥ २ ॥)

॥ * ॥ सवर्णेऽण्ग्रहणमपरिभाष्यमाकृतिग्रहणात् ॥ * ॥

(भाष्यम्)

सवर्णेऽण्ग्रहणमपरिभाष्यम् ॥

कुतः ?

'आकृतिग्रहणात्' । अवर्णाकृतिरुपदिष्टा सर्वमवर्णकुलं ग्रहीष्यति । तथा-इवर्णाकृतिः, तथा-उवर्णाकृतिः ॥

(प्रदीपः) आकृतिपक्षे सूत्रं न कर्तव्यमित्याह—सवर्ण इति । प्रत्याहारे अनुवृत्तिनिर्देशे च सर्वत्र जातिरुपदिश्यते, नान्तरीयकं व्यक्त्युच्चारणम् । अत्वं च ह्रस्वदीर्घप्लुतेषु विद्यते, यथा—गोत्वं कृशे गोपिण्डे स्थूले शुक्ले चेति भावः ॥

(उद्योतः) नास्तीहेति । यदि त्वइउणित्यादावत्वादि जातिनिर्देशादेशामण्त्वम्, प्रत्याहारग्रहणेषु च न दोषः, इत्वादय इत्यादिनिर्देशाश्चात्रैवार्थे लिङ्गमित्युच्यते, तदा सूत्रमेव व्यर्थमित्याह—आकृतीति ॥ प्रत्याहारे-अइउणित्यादिसूत्रे । अनुवृत्तिनिर्देशे-अस्य च्वावित्यादौ । उपदिश्यते-उच्चार्यते प्रत्याय्यते वा ॥ नान्तरीयकमिति । जातेः साक्षादुच्चारणासंभवात्तदुच्चारणम् । किंच जातौ कार्यान्वयस्य व्यक्तिं विना साक्षादसंभवात्तदुच्चारणं-तद्बोधनमित्यर्थः ॥ तत्र दीर्घादिव्यक्त्याक्षेपे बीजमाह—अत्वं चेति ॥ प्रमाणकृतभेदे दृष्टान्तमभिधाय गुणकृतभेदेऽप्याह—शुक्ल इति ॥

(आक्षेपभाष्यम्)

ननु चान्याऽऽकृतिरकारस्य, अन्याऽऽकारस्य च॥

(प्रदीपः) **ननु चान्येति** । श्रुतिभेदाद्भेदं मन्यमानस्य प्रश्नः ॥

(उद्योतः) श्रुतिः—श्रवणोपलब्धिः ॥ भेदाद्भेदमिति । जातेरिति शेषः ॥

(३९७ समाधानवार्तिकम् ॥ ३ ॥)

॥ * ॥ अनन्यत्वाच्च ॥ * ॥

(भाष्यम्)

अनन्याऽऽकृतिरकारस्य, आकारस्य च ॥

(प्रदीपः) **अनन्यत्वाच्चेति** । सत्यपि श्रुतिभेदे एकाकृतियोगोऽस्त्येव । यथा—कृशे स्थूलेऽपि च गोपिण्डे गोत्वयोगः ॥

(उद्योतः) **सत्यपीति** । श्रुतिभेदो हि व्यक्तिभेदसाधको नाकृतिभेदसाधक इति भावः ॥ अत एव ह्रस्वोऽयमकारो दीर्घोऽयमकार इति अत्वेन सामानाधिकरण्यानुभवः ॥ इकारादिष्वत्वमननुभवाच्च । अत एवोदात्तादयो न जात्यन्तरप्रयोजका इति तात्पर्यम् ॥ न च आकारोऽयं न अकार इति प्रतीत्यनापत्तिः, तस्या व्यक्तिभेदविषयकत्वात् ॥

(३९८ समाधानसाधकं वार्तिकम् ॥ ४ ॥)

॥ * ॥ अनेकान्तो ह्यनन्यत्वकरः ॥ * ॥

(भाष्यम्)

यो ह्यनेकान्तेन भेदो नासावन्यत्वं करोति । तद्यथा—न यो गोश्च गोश्च भेदः सोऽन्यत्वं करोति । यस्तु खलु गोश्चाश्वस्य च भेदः सोऽन्यत्वं करोति ॥

(प्रदीपः) **यो हीति** । अभेदस्यापि प्रत्यभिज्ञानात्सद्भाव इत्यर्थः ॥ **यस्त्विति** । अत्रापि यदा **प्राणी न हन्तव्य** इति प्राणित्वेनाश्रयणं तदा—अभेद एव, गवाश्वरूपाश्रयेण तु भेद इति भावः ॥ 'अष्टन आ विभक्तौ' इत्यत्र तु यत्नाधिक्याद्दीर्घव्यक्तिसमवेतं सामान्यं गृह्यते । यथा—**पूर्ववया ब्राह्मणः प्रत्युत्थेय** इति विशिष्टव्यक्तिस्थं ब्राह्मण्यमाश्रीयते ॥

(उद्योतः) भाष्ये—**अनेकान्तेनेति** । अनियमेनेत्यर्थः ॥ अभेदेन समानाधिकरण इति भावः । तदाह—**अभेदस्यापीति** ॥ **प्रत्यभिज्ञानादिति** । स एवायमिति प्रत्यभिज्ञानादित्यर्थः ॥ अकारोऽकार इत्येकाकारप्रत्ययाच्चेत्यपि बोध्यम् ॥ **नासावन्यत्वमिति** । भेदप्रतीतिमेवेत्यर्थः ॥ **प्राणीति** । यद्यपि प्राणित्वं न जातिस्तथापि साधारणधर्मत्वाभिप्रायेणोक्तम् ॥ **गवाश्वरूपेति** । गोत्वाश्वत्वेत्यर्थः ॥

परे तु ह्रस्वपङ्क्तिभेदवृत्त्येव-अत्वं, दीर्घपङ्क्तिभेदवृत्त्येव-आत्वमित्यादिर्ननु चेति भाष्याशयः । सकलव्यापकमत्वमप्यस्तीत्युत्तरम् । ननु व्यापकजात्यैक्येऽपि व्याप्यजात्या भेदोऽप्यस्तीत्यत आह—**अनेकान्तो हीति** । व्यापकधर्मेण समानाधिकरणव्याप्यधर्मकृतो भेदः केवलभेदबुद्धिं न करोतीत्यर्थ इत्याहुः ॥

ननु जातिनिर्देशेऽष्टन आ इत्यादावपि तन्निर्देशात् अकारादयः स्युः । यत्नाधिक्यं तूभयार्थं स्यात । ह्रस्वोच्चारणे तु अर्धमात्रिकनस्यान्तरतम्याद् ह्रस्व एव स्यादत आह—**अष्टन इति** ॥ **दीर्घव्यक्तीति** । व्यक्तेरुपलक्षणत्वे आन्तरतम्याद्ध्रस्व एव स्यादिति यत्नाधिक्यानर्थक्यं तदवस्थमिति विशेषणत्वमेव तस्या इति भावः । अत्वातिरिक्तमात्वादि नास्त्येवेति तात्पर्यम् ॥

केचित्तु दीर्घपङ्क्तिभेदवृत्त्यात्वजातेरेवात्वव्याप्यायास्तत्र निर्देश इति वदन्ति ॥

(मतान्तरनिदर्शकं भाष्यम्)

अपर आह—

(जातिपक्षोपस्थापकमन्यदीयवार्तिकम्)

॥ * ॥ सवर्णेऽण्ग्रहणमपरिभाष्यमाकृतिग्रहणादनन्यत्वम् ॥ * ॥

(भाष्यम्)

सवर्णेऽण्ग्रहणमपरिभाष्यम्, आकृतिग्रहणादनन्यत्वं भविष्यति ॥ अनन्याऽऽकृतिरकारस्य, आकारस्य च ॥

(अन्यदीयं वार्तिकम्)

॥ * ॥ अनेकान्तो ह्यनन्यत्वकरः ॥ * ॥

(भाष्यम्)

यो ह्यनेकान्तेन भेदो नासावन्यत्वं करोति । तद्यथा—न यो गोश्च गोश्च भेदः सोऽन्यत्वं करोति । यस्तु खलु गोश्चाश्वस्य च भेदः सोऽन्यत्वं करोति ॥

(प्रदीपः) **अपर आहेति** । व्यक्तिरेव शब्दार्थः । जातिस्त्वशब्दार्थोऽपि अभेदप्रत्ययहेतुरस्तीति सर्वव्यक्तीनामभेदेनाश्रयणादेकव्यक्तिनिर्देशेऽपि ग्रहणं सर्वव्यक्तीनां सिध्यतीत्यर्थः ॥ अत्र पक्षे—आकृतिग्रहणमाकृतेरेकाकारप्रत्ययनिमित्तत्वेन प्रतिपत्तिरुच्यते ॥

(उद्योतः) **अशब्दार्थ इति** । शब्दजन्यप्रतीतिविशेष्यत्वाभाववानित्यर्थः । यद्वा शक्यतावच्छेदकत्वेऽप्यशक्य इत्यर्थः ॥ **सर्वव्यक्तीनामिति** । जातिवैशिष्ट्येन प्रत्येकवृत्तिपरस्परभेदत्यागपूर्वकमभेदेनैकरूपेणाश्रयणाच्च जात्याक्रान्तसर्वव्यक्तीनां ग्रहणं सिध्यतीत्यर्थः ॥ पूर्ववार्तिकेऽण्ग्रहणाकरणे-आकृतिग्रहणं हेतुः, आकृतेरपि भेदाशङ्कायामनन्यत्वाच्चेति वार्तिकखण्डः । अपरमतेऽण्ग्रहणाकरणे-सर्वव्यक्तीनामनन्यत्वं हेतुः, अनन्यत्वे-आकृतिग्रहणम् । आकृतेर्ग्रहणं-विशेषणत्वेनाश्रयणम् ॥ रूपसामान्यादित्यमाकृतिग्रहणा-

दिलस्यार्थोऽपरमत इत्येके ॥

(सिद्धान्तसाधकं भाष्यवार्तिकम्)

॥ तद्वच्च हल्ग्रहणेषु ॥

(भाष्यम्)

एवं च कृत्वा हल्ग्रहणेषु सिद्धं भवति । "झलो झलि"-अवात्ताम्, अवात्तम्, अवात्त । यत्रैतन्नास्ति-अण् सवर्णान् गृह्णातीति ॥

(प्रदीपः) **तद्वच्चेति** । यथा-आकृतिग्रहणादण्सु कार्यं सिध्यति, तथा हल्ष्वपि आकृतिग्रहणादेव सिध्यति । व्यक्तिपक्षे तु एकैव तकारव्यक्तिर्झल्व्यपदेशमासादयेत् पूर्वा परा वा-इति 'अवात्ताम्' इति लोपो न स्यात् । 'अवुद्ध' इत्यादावेव तु स्यात् ॥

(उद्द्योतः) जात्याश्रयणमावश्यकमित्याह—**तद्वच्चेति** । **पूर्वा परा वेति** । उभयोरपि झल्त्वं न स्यात्, अन्यतरस्य प्रत्याहारस्थलोपासादन्यत्वादिति भावः ॥ **अवात्तामिति** । वसेर्लुङि तसस्तामि धृद्धौ सःसीति तत्वे **झलो झलीति** सिज्लोपे रूपम् ॥ ननु झल इति सूत्रं क्व चरितार्थमत आह—**अवुद्धेति** । बुधेर्लुङि रूपम् ॥

(सिद्धान्तसाधकं भाष्यवार्तिकम् ॥)

॥ अनेकान्तो ह्यनन्यत्वकरः ॥

(भाष्यम्)

इत्युक्तार्थम् ॥

(प्रदीपः) धातुप्रत्ययावयवयोस्तकारयोर्भेद एवेति चेत्, तत्राह—**अनेकान्त इति** ॥

(उद्द्योतः) **भेद एवेति** । व्यक्त्योः परस्परं भेद एवेति भावः ॥ भाष्ये—**अनेकान्त इति** । उपात्ताभेदकधर्मसमानाधिकरणो भेदकधर्म इत्यर्थः । प्रकृते भेदकधर्मस्तात्त्वम् ॥

(सिद्धान्तसाधकं भाष्यवार्तिकम् ॥)

॥ द्रुतविलम्बितयोश्चानुपदेशात् ॥

(भाष्यम्)

द्रुतविलम्बितयोश्चानुपदेशान्मन्यामहे—'आकृतिग्रहणात् सिद्धम्' इति । यदयं कस्यांचिद् वृत्तौ वर्णानुपदिश्य सर्वत्र कृती भवति ॥

(प्रदीपः) **द्रुतेति** । हल्ग्रहणेष्वेवेदमुच्यते, यत्रैतन्नास्ति अण् सवर्णान् गृह्णातीति । अण्सु तु व्यक्तिनिर्देशेऽपि ग्रहणकशास्त्रेण स्यादेव वृत्तिभिन्नस्य ग्रहणम् ॥

(उद्द्योतः) प्रयोगार्थे तु मध्यमा-इत्युक्तेर्द्रुतविलम्बितयोरित्युक्तम् ॥

(काकुभाष्यम्)

अस्ति प्रयोजनमेतत् ॥
किं तर्हीति ?

(वृत्तिपृथक्त्वबोधनम्)

(३९९ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ वृत्तिपृथक्त्वं तु नोपपद्यते ॥ * ॥

(भाष्यम्)

वृत्तेस्तु पृथक्त्वं नोपपद्यते ॥

(प्रदीपः) **वृत्तिपृथक्त्वमिति** । ह्रस्वदीर्घादिप्रमाणलक्षणाऽपि वृत्तिर्न भेदिका स्यादिति खट्वाभिरित्यैस् प्रसज्येतेति भावः ॥

(उद्द्योतः) **ह्रस्वदीर्घादीति** । वृत्त्या=कालप्रमाणेन पृथक्त्वमिति तृतीयासमास इति भावः । भाष्ये तु शेषत्वविवक्षया षष्ठी । हेतौ पञ्चमी वा ॥

(समाधाने भाष्यवार्तिकम् ॥)

॥ तस्मात्तत्र तपरनिर्देशात्सिद्धम् ॥

(भाष्यम्)

तस्मात्तत्र तपरनिर्देशः कर्तव्यः ॥

(समाधानभाष्यम्)

न कर्तव्यः । क्रियते न्यास एव—"अतो भिस ऐस्" इति ॥ अणुदित्सवर्णस्य चाप्रत्ययः ॥ ६९ ॥

(प्रदीपः) **क्रियत इति** । अवश्यकर्तव्यतां दर्शयति । व्यक्तिपक्षेऽण् सवर्णान् गृह्णातीति प्रसङ्गः । सूत्रप्रत्याख्याने त्वाकृतिग्रहणात् ॥ उदिद्ग्रहणं कर्तव्यमेव । न हि वर्ग्याणामेकाकृतियोगोऽस्ति । स्थिते तु सूत्रे **कुद्दोश्चुरित्यादौ** भाव्यमानस्य उदित्त्वसामर्थ्याद्**अप्रत्यय** इति निषेधो नावतरतीत्यण्स्वेनायं निषेधः । प्रत्याख्यानपक्षे भाव्यमानेषु यथाश्रुतं रूपमुत्पद्यत इत्याकृतिग्रहणेऽपि भिन्नकालानां ग्रहणं न भवति । यथा **पशुना यजेत पशुमालभेते**त्युत्पत्तिवाक्यत्वात् संख्या विवक्ष्यते । उदात्तादयस्त्वभेदका इत्युक्तम् । अनुवादे तु नान्तरीयकत्वादेकव्यक्त्युच्चारणेऽपि सकलव्यक्तिग्रहणम् । यथा ग्रहं **संमार्ष्टीति** सर्वेषां ग्रहाणां 'प्राजापत्या नव ग्रहाः' इत्यादिभ्यो वाक्येभ्यो ज्ञातानां संमार्जनम् ॥ ६९ ॥

(उद्द्योतः) **आकृतिग्रहणादिति** । तदुक्तमृऌउण्सूत्रभाष्ये—*तद्वच्च तपरकरणम्* एवंच कृत्वा तपराः क्रियन्ते आकृतिग्रहणेनातिप्रसक्तमिति कृत्वेति ॥ **एकाकृतियोग इति** । तन्मात्रनिष्ठेत्यादिः ॥ **उदिदिति** च कुचुटुतुपूनां प्राचां संज्ञा, तयेहापि व्यवहारः ॥ न तु सर्वत्रेत्संज्ञा प्राप्नोति, अनुवादे तदप्राप्तेरिति बोध्यम् ॥ नन्वण्ग्रहणप्रत्याख्यानेऽनुवादेष्विव विधावपि जातिनिर्देशात्सर्वग्रहणप्रसङ्ग इत्यत आह—**भाव्यमानेष्विति** ॥ **यथाश्रुतमिति** । जातिविशेषावच्छिन्नव्यक्तिविशेषरूपमित्यर्थः ॥ **उत्पत्तिवाक्यत्वादिति** । विधिवाक्यत्वादित्यर्थः । विधौ हि प्रमित्सितत्वाद्विशिष्टोपादाने न वाक्यभेदः । अनुवादे तु तस्य सिद्धत्वेनाप्रमित्सितत्वात्तद्विशेषणोपादानं न वाक्यभेदमन्तरेण भवति, स चान्याय्य इति भावः । यत्तु क्वचिद्विधावपि व्यक्त्यन्तरस्योपादानम्, तदिह उदित्यादौ तपरत्वाल्लिङ्गादिति द्रष्टव्यमित्याहुः ॥ **नान्तरीयकत्वादिति** । अनेन नान्तरीयकविशेषणविषय एव विवक्षाऽविवक्षा-

विचार इति ध्वनयति । अत एव न 'श्रेयांसं प्रबोधयेत्' इत्यादौ अनुवाद्यविशेषणश्रेयस्त्वादेर्विवक्षायामपि दोषः ॥ वस्तुतोऽत्र व्याख्यानमेव शरणं, नान्तरीयकसङ्ख्यालिङ्गविषयन्यायस्य प्रधानव्यक्तिविषयकत्वानौचित्यात् । उपेयिवानित्यादौ उपेत्यविवक्षाया नञो विवक्षायाश्च दर्शनात् ॥ ऋकारेण लृग्रहणाय तु लृवर्णस्य ऋवर्णवद्भावो वाच्य इति तात्पर्यम् ॥

परे तु जातिपक्षेऽपि तपरसूत्रस्य जातिग्रहणप्राप्तसवर्णग्रहणनियमार्थत्ववत्तत्प्रयुक्तसवर्णग्रहणनिषेधायाप्रत्यय इति पृथक् कार्यमेव । ध्वनितं चेदं ज्यादादीयस इति सूत्रे भाष्ये ॥ किं च तत्र व्यक्तिविवक्षायां यत्र क्वचित् प्रयोगे एकाऽकारव्यक्तिः साध्वी स्यान्न प्रयोगान्तरे इति व्यक्तिविवक्षया समाधानं दुर्घटमित्याहुः ॥ ६९ ॥

—•०५०•—

(६४ तपरसंज्ञासूत्रम् ॥ १ । १ । ९ आ. १० सू. ॥)

तपरस्तत्कालस्य ॥ १ । १ । ७० ॥

(तत्कालपदसाधनम्)

(आक्षेपभाष्यम्)

अयुक्तोऽयं निर्देशः । 'तत्' इत्यनेन कालः प्रतिनिर्दिश्यते, तदित्ययं च वर्णः । तत्रायुक्तं वर्णस्य कालेन सह सामानाधिकरण्यम् ॥

(प्रदीपः) तपरः० ॥ ७० ॥ **अयुक्त इति** । न्यायेनासंबद्ध इत्यर्थः । न्यायशब्दस्य तु प्रयोगः प्रसिद्धत्वान्न कृतः । कदाचित्तु प्रसिद्धार्थस्यापि प्रयोगो दृश्यते—न्यायेनायुक्तमिति । धात्वर्थेऽन्तर्भूतस्य प्रयोगाभावः, न हि भवति—जीवति प्राणानिति ॥ **तदित्यनेनेति** । स कालो यस्येति कालसामानाधिकरण्येन तच्छब्दोपादानात् ॥ **तदित्ययं च वर्ण इति** । परामृष्ट इत्यर्थः, तपरशब्दवाच्यस्यार्थस्य तच्छब्देन परामर्शात् ॥ **वर्णस्येति** । वर्णवाचिनस्तच्छब्दस्येत्यर्थः ॥ **कालेनेति** । कालवाचिनेत्यर्थः । कालो हि प्रसिद्धपरिमाणा क्रियाऽप्रसिद्धपरिमाणस्य क्रियाऽन्तरस्य परिच्छेदिका, यथा—दिवसमधीत इति । दिवसशब्देनोदयादिरस्तमयान्त आदित्यगतिप्रबन्ध उच्यते । स चाध्ययनस्य परिच्छेदकत्वात्कालः । वर्णस्तु क्रियात्मको न भवति ॥

(उद्योतः) तपरस्तत्का० ॥ ७० ॥ युजेः संबन्धवाचकत्वेन संबन्धस्योभयनिरूप्यत्वेन संबन्ध्यन्तराकाङ्क्षायामाह—**न्यायेनेति** ॥ **प्रसिद्धत्वादिति** । निष्ठान्तयुजेः प्रायो न्यायसंबन्धिन्येव प्रयोगादित्यर्थः ॥ नन्वेवं युज्यर्थेऽन्तर्भूतत्वादप्रयोग इति कुतो नोच्यत इत्यत आह—**धात्वर्थे इति** । यद्ययमन्तर्भूतः स्यात्तदा न्यायेनायुक्त इति प्रयोगो न स्यादिति भावः ॥ दण्डेनायुक्त इत्यादि च न स्यादित्यपि बोध्यम् ॥ एतेन मेघो वर्षतीत्यादौ प्रसिञ्चा जलमित्यादेरप्रयोगादकर्मकतेति नव्योक्तिः परास्ता ॥ भाष्ये-**प्रतिनिर्दिश्यत इति** । सामानाधिकरण्येन विशेष्यत इत्यर्थः ॥ तदित्ययं च वर्ण इत्यस्य साकाङ्क्षत्वादाह—**परामृष्ट इति** ॥ वर्णस्यैव परामर्शे हेतुमाह—**तपरेति** । तः परो यस्मादिति विग्रहेऽव्यवहितोत्तरत्वस्य सप्रयोजनत्वात् सवर्णत्वस्य वर्णनिष्ठत्वाच्च तेन वर्ण एवोच्यते इति भावः ॥ एकार्थवृत्तित्वरूपसामानाधिकरण्यस्य शब्दधर्मत्वात् कथं वर्णस्य कालेनेति भाष्यमत आह—**वर्णवाचिन इति** ॥ सामानाधिकरण्यानुपपत्तिप्रदर्शनाय कालस्वरूपमाह—**कालो हीति** ॥ अपरिच्छिन्नस्य विभोः कालस्य व्यवहारानुपयोगित्वादाह—**प्रसिद्धेति** ॥ **वर्णस्त्विति** । गुणरूपत्वाद् द्रव्यरूपत्वाद्वेत्यर्थः ॥ जन्यमात्रं कालोपाधिरिति तु न युक्तम् । दिवसादिव्यवहारस्य सूर्यक्रियादिभिरेव दर्शनाद् इति भावः । एतत्कालस्वरूपकथनं कालाः **परिमाणिनेति** सूत्रस्थभाष्यविरुद्धमिति तत्रैवोपपादयिष्यते ॥

(प्रत्याक्षेपभाष्यम्)

कथं तर्हि निर्देशः कर्तव्यः ?

(प्रत्याक्षेपसमाधानभाष्यम्)

तत्कालकालस्येति ॥

(आक्षेपभाष्यम्)

किमिदं तत्कालकालस्येति ?

(समाधानभाष्यम्)

तस्य कालः—तत्कालः, तत्कालः कालो यस्येति सोऽयं-तत्कालकालः, तत्कालकालस्येति ॥

(प्रदीपः) **तस्य काल इति** । यैव एकस्य वर्णस्य परिच्छेदिका क्रिया निमेषादिः सैव यस्य परस्य, सः-तत्कालकालः ॥

(उद्योतः) **सैवेति** । तज्जातीयेत्यर्थः ॥

(तटस्थाक्षेपभाष्यम्)

स तर्हि तथा निर्देशः कर्तव्यः ॥

(सिद्धान्तिसमाधानभाष्यम्)

न कर्तव्यः । उत्तरपदलोपोऽत्र द्रष्टव्यः । तद्यथा—उष्ट्रमुखमिव मुखं यस्य सोऽयमुष्ट्रमुखः । खरमुखः । एवं तत्कालकालः—तत्कालः, तत्कालस्येति ॥

(प्रदीपः) **उष्ट्रमुख इति** । गम्यमानार्थत्वात् द्वितीयमुखशब्दाप्रयोगः । उष्ट्रो मुखमस्योष्ट्रमुखः । न च प्राणी प्राण्यन्तरस्य मुखमिति सामर्थ्यात्सादृश्यप्रतीतिः । समग्रेण चोष्ट्रेण मुखस्य सादृश्याभावादुष्ट्रशब्दोऽवयवे वर्तते । मुखेनैव मुखस्य सादृश्यं प्रसिद्धमिति सामर्थ्यात्—उष्ट्रमुखमिव मुखमस्येत्यर्थो गम्यते । एवमिहापि वर्णः कालो न भवतीति सामर्थ्यात्तदीया क्रिया क्रियान्तरपरिच्छिन्ना सती क्रियान्तरस्य परिच्छेदिकेति वर्ण एव परिच्छेदक उच्यते ॥

(उद्योतः) **तदीया क्रियेति** । उच्चारणरूपेत्यर्थः ॥ क्रियान्तरस्य-वर्णान्तरोच्चारणस्य ॥ **वर्ण एवेति** । वर्णाभिव्यञ्जकक्रियागतपरिच्छेदकत्वस्याश्रये उपचाराद्वर्णपरामर्शिनस्तच्छब्दस्य मुख्यवृत्तेरेव कालशब्देन सामानाधिकरण्यमित्यर्थः ॥

(समाधानान्तरभाष्यम्)

अथवा—साहचर्यात्ताच्छब्द्यं भविष्यति । कालसहचरितो वर्णः, वर्णोऽपि काल एव ॥

(प्रदीपः) **अथवेति** । वर्णसहचरितायां क्रियायां

तच्छब्दो वर्तते, स कालो यस्येति तद्वर्णसमवेता क्रिया परिच्छेदिकाऽस्येत्यर्थः । यथा – अश्मादि द्रव्यं द्रव्यान्तरपरिच्छिन्नं सुवर्णादीनां परिच्छेदकं, तद्वत् क्रियाऽपीत्यर्थः ॥

(उद्द्योतः) पूर्वव्याख्यातो विशेषमाह—वर्णसहेति । अनेन लक्षणाबीजं संबन्धो दर्शितः ॥ क्रियायाः परिच्छेदकत्वं सापेक्षं, न स्वत इति दृष्टान्तेनाह—यथेति ॥

(विध्यर्थत्वनिर्णयः)

(आक्षेपभाष्यम्)

किं पुनरिदं नियमार्थम्, आहोस्वित् प्रापकम्?

(उद्द्योतः) भाष्ये–प्रापकमिति । स्वतन्त्रविधायकमित्यर्थः ॥

(प्रत्याक्षेपभाष्यम्)

कथं च नियमार्थं स्यात्? कथं वा प्रापकम्?

(प्रत्याक्षेपसमाधानभाष्यम्)

यद्यण्ग्रहणमनुवर्तते, ततो नियमार्थम् । अथ निवृत्तम्, ततः प्रापकम् ॥

(विशेषजिज्ञासाभाष्यम्)

कश्चात्र विशेषः?

(४०० नियमपक्षे दूषणवार्तिकम् ॥ १ ॥)

॥ * ॥ तपरस्तत्कालस्येति नियमार्थमिति चेद्दीर्घग्रहणे स्वरभिन्नाग्रहणम् ॥ * ॥

(भाष्यम्)

"तपरस्तत्कालस्य" इति नियमार्थमिति चेद्दीर्घग्रहणे स्वरभिन्नानां ग्रहणं न प्राप्नोति ॥

केषाम्?

उदात्तानुदात्तस्वरितानाम् ॥

(प्रदीपः) दीर्घग्रहण इति । भेदका उदात्तादय इति भावः ॥ तत्र वृद्धिरादैजिति षण्णामाकाराणां वृद्धिसंज्ञेष्यते, एकस्यैव तु दीर्घस्य स्यात् ॥ तपरकरणं त्वैजर्थमेव स्यात् ॥

(उद्द्योतः) षण्णामिति । अनुनासिकाकारस्य वृद्धिसंज्ञायां फलाभावादवसाने तदभावाच्चेदं चिन्त्यम् । अत एव वार्तिके—स्वरभिन्नेत्येवोक्तम्, न तु गुणभिन्नेति । भाष्येऽप्युदात्तानुदात्तस्वरितानामित्येव पाठः ॥ ननु तत्र तपरत्वसामर्थ्यादस्य सूत्रस्यावृत्तिमङ्गीकृत्यावृत्तस्याणग्रहणाननुवृत्त्या विध्यर्थत्वान्न दोष इत्यत—आह—तपरकरणमिति ॥

(प्रापकपक्षाभ्युपगमभाष्यम्)

अस्तु तर्हि प्रापकम् ॥

(४०१ प्रापकपक्षे दूषणवार्तिकम् ॥ २ ॥)

॥ * ॥ प्रापकमिति चेद् ह्रस्वग्रहणे दीर्घप्लुतप्रतिषेधः ॥ * ॥

(भाष्यम्)

प्रापकमिति चेद् ह्रस्वग्रहणे दीर्घप्लुतयोस्तु प्रतिषेधो वक्तव्यः ॥

(प्रदीपः) ह्रस्वग्रहण इति । 'अतो भिस ऐस्' इत्यकारग्रहणे पूर्वसूत्रेण दीर्घप्लुतयोर्ग्रहणं प्राप्नोति । इदं हि सूत्रमनण्ग्रहणे चरितार्थम् ॥

(समाधानभाष्यम्)

न वक्तव्यः ॥

(समाधाने भाष्यवार्तिकम्)

॥ विप्रतिषेधात् सिद्धम् ॥

(भाष्यम्)

अण् सवर्णान् गृह्णातीत्येतदस्तु, "तपरस्तत्कालस्य" इति वा । "तपरस्तत्कालस्य" एतद्भवति विप्रतिषेधेन ॥ अण् सवर्णान् गृह्णातीत्यस्यावकाशः—ह्रस्वा अतपरा अणः । 'तपरस्तत्कालस्य' इत्यस्यावकाशः—दीर्घास्तपराः । ह्रस्वेषु तपरेषूभयं प्राप्नोति । "तपरस्तत्कालस्य" इत्येतद्भवति विप्रतिषेधेन ॥

(प्रदीपः) विप्रतिषेधादिति । विरोधो ह्यत्र विद्यते । यदि पूर्वसूत्रेणाकारः सवर्णानां ग्राहकस्तदाऽष्टादशानां ग्रहणप्रसङ्गः, अनेन तु षण्णाम् । तत्र परत्वादनेनैव तपरोऽण् सवर्णानां तत्कालानां स्वरूपस्य च ग्राहकः ॥ ननु 'अतः' इति तकारोच्चारणसामर्थ्यादनेनैव ग्रहणं भविष्यति, किं विप्रतिषेधाश्रयेण ॥ नैतदस्ति । मुखसुखार्थस्यापि तकारस्य दर्शनात्, ऋत इद्धातोरिति यथा ॥

(उद्द्योतः) नन्वाकडारादन्यत्र संज्ञासमावेशदर्शनाद्विप्रतिषेधादित्ययुक्तमत आह—विरोधो हीति । न हि संज्ञासमावेशे संज्ञात्वं प्रयोजकं, किंतु विरोधाभाव इति भावः ॥ सङ्ख्याकृतव्यवहारस्य परस्परपरिहारेणैव दृष्टत्वादत्र युगपदसंभवरूपो विरोध इति तात्पर्यम् ॥ तपरत्वसामर्थ्यात् प्रतिलक्ष्यं लक्षणभेदाश्रयणात्तो भिस इत्येतद्विषयं तपर इति लक्षणमनवकाशमित्ययुक्तो विप्रतिषेध इति शङ्कते—अत इतीति ॥ तपरत्वस्य संदिग्धत्वाद् विप्रतिषेधोपपत्तिरित्युत्तरयति—नैतदिति ॥ ऋत इदिति । अत्र भाव्यमानत्वेन सवर्णाग्राहकत्वात्तथा तपरत्वं मुखसुखार्थं तथेत्यर्थः ॥ ॠत इति तपरत्वं तु गुणान्तरयुक्तसङ्ग्रहार्थम् । अन्यथोदात्तोच्चारणे 'तीर्णः' इत्यत्र क्ते भत्ययसंनियुक्ताद्युदात्तत्वे शेषनिघाते चोदात्तत्वाभावाश्च स्यात् । अनुदात्तोच्चारणे जीर्यतीत्यत्र न स्यादिति भावः ॥

(स्फोटस्यैकत्वनिरूपणम्)

(भाष्यम्)

यद्येवम्—

(४०२ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ द्रुतायां तपरकरणे मध्यमविलम्बितयोरुपसंख्यानं कालभेदात् ॥ * ॥

(भाष्यम्)

द्रुतायां तपरकरणे मध्यमविलम्बितयोरुप-

संख्यानं कर्तव्यम् । तथा मध्यमायां द्रुतविलम्बितयोः । तथा विलम्बितायां द्रुतमध्यमयोः ॥

किं पुनः कारणं न सिध्यति ?

'कालभेदात्' । ये हि द्रुतायां वृत्तौ वर्णास्त्रिभागाधिकास्ते मध्यमायाम् । ये च मध्यमायां वर्णास्त्रिभागाधिकास्ते विलम्बितायाम् ॥

(प्रदीपः) यद्येवमिति । यद्ययं योगस्तत्कालान् प्रतिपादयन् भिन्नकालान् निवर्तयतीत्यर्थः ॥ त्रिभागाधिका इति । द्रुतं श्लोकं ऋचं वोच्चारयति वक्तरि नाडिकाया यस्या नव पानीयपलानि स्रवन्ति तस्या एव मध्यमायां वृत्तौ द्वादश पलानि स्रवन्ति । नवानां त्रिभागास्त्रीणि पलानि, तदधिकानि नव द्वादश सम्पद्यन्ते । विलम्बितायां वृत्तौ षोडश पलानि स्रवन्ति ॥

(उद्द्योतः) भिन्नकालानिति । परत्वेन पूर्वसूत्रबाधादिति भावः ॥ अप्राप्तिरेवात्र निवृत्तिः ॥ भाष्ये—यद्येवमित्यस्य एतद्विषये पूर्वसूत्राप्रवृत्तावित्यर्थः । यस्यां वृत्तौ तपरकरणं तदन्यत्र वृत्तौ प्रयोगे पेसादीनामुपसङ्ख्यानं कार्यमिति तात्पर्यम् ॥

अभ्यासार्थे द्रुता वृत्तिः प्रयोगार्थे तु मध्यमा ।

शिष्याणामुपदेशार्थं वृत्तिरिष्टा विलम्बिता ॥ इति—

वृत्तिषु उपलब्धय एव भिन्नकालाः । वर्णास्तु तत्काला एवेत्यभिसन्धाय भाष्ये—किंपुनरिति प्रश्नः ॥ तत्तत्कालावच्छिन्नताल्वोष्ठपुटव्यापारजन्या भिन्नकाला एवेत्याशयेन कालभेदादित्युत्तरम् ॥ त्रिभागाधिका इति । तृतीयभागाधिका इत्यर्थः, कैयटात्तथा प्रतीतेः ॥ त्रयो भागा अधिका इत्यर्थस्तु उचितः । केवलसङ्ख्यावाचकानां पूरणप्रत्ययान्तार्थकत्वे मानाभावात्तत्रासाधुत्वाच्चेति परे ॥ यस्या नाडिकाया इति । सुषुम्नाया इत्यर्थः । पलानि—बिन्दवः । ब्रह्माण्डसंबद्धा साऽमृतबिन्दुस्राविणीति प्रसिद्धिर्योगिनाम् ॥

(४०३ समाधानवार्त्तिकम् ॥ ४ ॥)

॥ * ॥ सिद्धं त्ववस्थिता वर्णा वक्तुश्चिराचिरवचनाद् वृत्तयो विशिष्यन्ते ॥ * ॥

(भाष्यम्)

सिद्धमेतत् ॥

कथम् ?

अवस्थिता वर्णा द्रुतमध्यमविलम्बितासु ॥

किं कृतस्तर्हि वृत्तिविशेषः ?

'वक्तुश्चिराचिरवचनाद् वृत्तयो विशिष्यन्ते' वक्तैव कश्चिदाश्वभिधायी भवति, आशु वर्णानभिधत्ते । कश्चिच्चिरेण । कश्चिच्चिरतरेण ॥ तद्यथा—तमेवाध्वानं कश्चिच्चिरेण गच्छति, कश्चिदाशु गच्छति, कश्चिच्चिरतरेण गच्छति । रथिक आशु गच्छति आश्विकश्चिरेण, पदातिश्चिरतरेण ॥

(प्रदीपः) सिद्धं त्विति । सर्वासु वृत्तिषु न वर्णानामुपचयापचयौ, यथा—गन्तॄणामालस्यादिभेदाद् गतिभेदेऽपि न मार्गभेद इत्यर्थः ॥

(उद्द्योतः) भाष्ये—सिद्धं त्विति । उत्पत्तिपक्षेऽपि उपलब्धीनामेव कालभेदाद्वृत्तित्रैविध्यम् । वर्णास्तु वृत्तिभेदेऽप्येकरूपा एवेत्यभिमानः ॥ अवस्थिताः—नियतकालाः ॥ चिराचिरवचनात्—चिराचिरकालोच्चारणजनकयत्नात् । जायमानवैकृतध्वनेरुपलब्धीनामेव भेद इति भावः ॥ उपचयापचयौ—कालवृद्धिह्रासौ ॥ आलस्यादिभेदादिति । आलस्यादिना गतिक्रियाया भेदेऽपि यथा न मार्गभेदस्तथाऽऽलस्यादिनोच्चारणक्रियातो वैकृतध्वनिभेदेऽपि न वर्णस्वरूपभेद इति भावः ॥

(समाधानबाधकभाष्यम्)

विषम उपन्यासः । अधिकरणमत्राध्वा व्रजतिक्रियायाः । तत्रायुक्तं यदधिकरणस्य वृद्धिह्रासौ स्याताम् ॥

(प्रदीपः) विषम इति । वर्णाः यत्नजन्याः, तद्भेदे वृत्तिभेदाद्भिन्नकाला एव । अध्वा तु व्यवस्थित एव, न गन्तृक्रियाजन्यः ॥

(उद्द्योतः) तद्भेदे-प्रयत्नभेदे ॥ तद्भेदेनेति तृतीयान्तः क्वचित्पाठः ॥ वृत्तिभेदात्-द्रुतादिवृत्तिभेदात् ॥ भिन्नकाला एवेति । चिराचिरोपलब्ध्युपयोगिवृद्धिह्रासयुक्ता एवेत्यर्थः ॥ अयं भावः—उत्पत्तिवादिनो वर्णोत्पत्तिं प्रति उच्चारणव्यापारस्य कारणत्वात्तावत्तावत्कालावच्छिन्नोच्चारणेन ह्रस्वदीर्घादेरिव द्रुतादेरपि तावत्कालस्यैवोत्पत्तिः स्यात् । न चानुनिष्पादी ध्वनिरेव तत्कालो न तु वर्ण इति वाच्यम् । विनिगमनाविरहादिति ॥

(समाधानसाधकभाष्यम्)

एवं तर्हि—स्फोटः शब्दः । ध्वनिः शब्दगुणः ॥

(आक्षेपभाष्यम्)

कथम् ?

(४०४ समाधाने दृष्टान्तवार्त्तिकम् ॥ ५ ॥)

॥ * ॥ भेर्याघातवत् ॥ * ॥

(भाष्यम्)

तद्यथा—भेर्याघातो भेरीमाहत्य कश्चिद्विंशतिपदानि गच्छति, कश्चित्त्रिंशत्, कश्चिच्चत्वारिंशत् । स्फोटस्तावानेव भवति । ध्वनिकृता वृद्धिः ॥

ध्वनिः स्फोटश्च शब्दानां ध्वनिस्तु खलु लक्ष्यते ।
अल्पो महांश्च केषांचिदुभयं तत्स्वभावतः ॥ १ ॥

तपरस्तत्कालस्य ॥ ७० ॥

(प्रदीपः) एवं तर्हीति । व्यक्तिस्फोटोऽत्र विवक्षितः । स च नित्यः । एतच्च येनोच्चारितेनेत्यत्र पस्पशायां विचारितमिति तत एव बोद्धव्यम् ॥ शब्दगुण इति । शब्दस्य गुणः—उपरञ्जकः, व्यञ्जकत्वेनेत्यर्थः । तद्यथा—घटः पुनः पुनर्दृश्यमानोऽपि न भेदमवलम्बते, तथा विलम्बितायां वृत्तावकार एव पुनः पुनरुपलभ्यत इति वृत्तिभेदेऽपि वर्णस्य भेदो न गृह्यत इति सर्ववृत्तिषु तत्कालत्वम् ॥ ह्रस्वदीर्घप्लुतास्तु स्वत एव भिन्ना भिन्नैर्ध्वनिभिर्व्यज्यन्त इति तेषां कालभेदः ॥ भेर्याघात इति । भेरीमाहन्तीति—भेर्याघातः । उपलब्धिसामान्ये दृष्टान्तः ।

यथा—प्रयत्नवशादुत्पन्नो भेरीशब्दः कश्चिदल्पकालमुपलभ्यते, कश्चिच्चिरं, कश्चिच्चिरतरं । एवं वृत्तिषूपलब्धीनां कालभेदः, विषयस्य त्वभेद एव ॥ **स्फोटस्तावानेवेति** । दार्ष्टान्तिकोपन्यासः ॥ **ध्वनिः स्फोटश्चेति** । व्यञ्जको व्यङ्ग्यश्चेत्यर्थः । शब्दानां व्यङ्ग्यानां संबन्धी व्यञ्जकत्वेन यो ध्वनिः स एव महानल्पश्च लक्ष्यते । व्यङ्ग्यस्त्वभिन्नकाल एवेत्यर्थः ॥ **उभयमिति** । व्यङ्ग्यो व्यञ्जकश्च प्रमाणेन स्वभावतः स्वरूपेण सिद्धावित्यर्थः ॥ **केषांचिदिति** । व्यक्तानामुभयं गृह्यते, अव्यक्तानां तु ध्वनिरेव ॥ ७० ॥

(**उद्द्योतः**) अतो नित्यमतिरिक्तं स्फोटमादाय समाधत्ते भाष्ये—**एवं तर्हीति** ॥ **अत्रेति** । भाष्ये इत्यर्थः ॥ **स च नित्य इति** । आकाशादिवदिति भावः ॥ ननु स्फोटोऽसिद्धस्तन्नित्यत्वं चेत्यत आह—**एतच्चेति** । स एवायमकार इति प्रत्यभिज्ञानात्, एकं पदमिति प्रत्ययाच्च तत्सिद्धिरित्यन्यत्र विस्तरः ॥ ननु ध्वनिरपि शब्दविशेष एव स कथं शब्दगुणोऽत आह—**शब्दस्येति** । व्यञ्जकत्वेन—स्फोटोपलब्धिप्रतिबन्धकस्तिमितवाय्वपसरणद्वारा स्वधर्मरूपिततदुपलब्धिहेतुत्वेनेत्यर्थः ॥ तद्विषयायाः पुनः पुनरुपलब्धेर्नैरन्तर्येऽपि न वर्णभेद इति दृष्टान्तेनोपपादयति—**तद्यथेति** ॥ पुनः पुनरुपलम्भः—अविच्छेदेन दर्शनम् ॥ **ह्रस्वदीर्घेत्यादि** । तमेवायं विलम्बितमुच्चारितवानन्यो द्रुतमितिवदिह व्यक्तिप्रत्यभिज्ञानाभावादिति भावः ॥ एवं च परिदृश्यमानकालभेदे उपलब्धिगत एवेति तात्पर्यम् ॥ अत्रेदं बोध्यम्—एक एव स्फोटस्तत्तद्वर्णस्तत्तद्रूपेणाभिव्यज्यते ॥ **ध्वनिः शब्दगुण** इति भाष्ये ध्वनिशब्देन वर्णो वैकृतध्वनिश्च ॥ तत्र वैकृतध्वनेः स्फोटस्य तद्रूपेण पुनः पुनरभिव्यक्तिः कार्यमिति तदभिव्यक्तस्फोटस्य तत्कालत्वमेव । ह्रस्वदीर्घप्लुतरूपस्फोटस्तु भिन्नकालावच्छिन्नैर्विजातीयैर्ध्वनिभिरभिव्यक्तो भिन्न एव, लौकिकैर्ध्वनिगतभेदेन तद्भेदस्यापि संप्रत्ययात् ॥ कैयटे **ह्रस्वदीर्घप्लुतास्तु स्वत एव भिन्ना** इत्यस्य व्यञ्जकभेदेनारोपितभेदा एव भिन्नैर्ध्वनिभिर्वर्णैर्व्यज्यन्त इत्यर्थः । विलम्बितादिवृत्तौ तु स्फोट एकजातीय एव । **ध्वनिकृता वृद्धिरि**त्यस्य वैकृतध्वनिकृतोपलब्धिकालवृद्धिरित्यर्थः । वर्णोपरागाभिव्यक्तिजनकयत्नीयकालोपरागेणैव स्फोटस्य भानम् । अत एवास्य प्राकृतत्वेन व्यवहारः । अयं तु वैकृतः । तस्य चाल्पत्वादिकृतत्वात् । वर्णाभिव्यक्त्युत्तरकालश्चायम् । अयं तूपलब्धेरेव पौनःपुन्ये कारणम् । पौनःपुन्यं चाविच्छेदेनोपलब्धिधारामात्रेण; न तु विच्छिद्य विच्छिद्योपलब्ध्या । एतदवच्छिन्नत्वेन तु न स्फोटोपलब्धिः, ह्रस्वाकार एवायमिति प्रत्यभिज्ञानात् । आरोपे सति **निमित्तानुसरणं, न तु निमित्तमस्तीत्यारोप** इति न्यायात् । उत्पत्तिवादिना त्वेवं वक्तुमशक्यमिति स्पष्टमेवेति ॥

ननु भेर्याघातो भेरीदण्डादिसंयोगविशेषः, स कथं गच्छेदत आह—**भेरीमिति** । कर्मण्यणिति भावः ॥ भाष्ये—**आहत्य** । तं शब्दमुपलभमान इति शेषः ॥ ननु दृष्टान्ते ध्वनेरुपलभ्यमानस्य भेदो न, तथेह वर्णस्य द्रुतादिष्विति वैषम्यमत आह—**उपलब्धिसामान्ये इति** । यथा तत्र तस्य ध्वनेस्तावत्तावत्कालमुपलम्भस्तथेहापि तत्तद्वृत्तौ तावत्तावत्कालं तत्तदभिव्यञ्जकरूपरूपितत्वेन परिच्छिन्नस्यैव स्फोटस्योपलम्भमात्रमित्येतावत्येव दृष्टान्तः । न चैतावता स्फोटभेद इति तात्पर्यम् ॥ ननु भेर्याघातस्थले स्फोटाभावात् स्फोटस्तावानेवेत्यनुपपन्नमत आह—**दार्ष्टान्तिकेति** ॥ भाष्ये—**ध्वनिः स्फोटश्च** । स्त इति शेषः ॥ किं तत इत्यत आह—**शब्दानामिति** । व्यञ्जकत्वेन—उपलब्धिजनकत्वेन । वैकृतध्वनेरप्युपलब्धिपौनःपुन्यकारणत्वाद्व्यञ्जकत्वमिति भावः ॥ तदुपक्रमेणैव भाष्यप्रवृत्तेः । **तदुभयं स्वभावतः**—सिद्धमिति शेषः ॥ न तु तत्र प्रमाणान्तरापेक्षेति भावः ॥ योगिप्रत्यक्षसिद्धं चैतदुभयमिति तात्पर्यम् ॥ इदमेव कैयटेन **प्रमाणेनेत्यनेनोक्तम्** ॥ वस्तुतस्तु भेर्याघातस्थलेऽपि स्फोट एव भेरीताडनाभिव्यक्तः श्रोत्रग्राह्यः । शब्दानां चिराचिरोपलब्धिकराल्पत्वमहत्त्ववान् वैकृतध्वनिरेवाल्पत्वादिना लक्ष्यते ॥ महत्त्वं—चिरकालत्वम् ॥ वैकृतध्वनिस्फोटयोः प्रमाणमाह—**उभयं तदिति** । तदुक्तं हरिणा—

> **वर्णस्य ग्रहणे हेतुः प्राकृतो ध्वनिरिष्यते ।**

ग्रहणे—तत्तत्कालकत्वेन ग्रहणे ।

> **वृत्तिभेदे निमित्तत्वं वैकृतः प्रतिपद्यते ॥**

इति,

> **शब्दस्योर्ध्वमभिव्यक्तेर्वृत्तिभेदाय वैकृतः ॥**

इति च । उभयमित्यावृत्त्या योजनीयम् । **उभयं गृह्यत** इति शेषः । तेन व्यक्तवाचामुभयम्, अव्यक्तवाचां वर्णधर्मानाक्रान्तध्वनिरेवेत्यर्थः । ध्वनिपदेन प्राकृतवैकृतावुभावपि उच्येते । ग्रहणकर्मीभूतमुभयं तु प्राकृतध्वनिस्फोटरूपम् । वैकृतस्याल्पत्वादि चिराचिरोपलब्ध्यनुमेयमिति बोध्यम् ॥ ७० ॥

(६५ प्रत्याहारसंज्ञासूत्रम् ॥ १ । १ । ९ आ. ११ सू. ॥)

आदिरन्त्येन सहेता ॥ १ । १ । ७१ ॥

(संज्ञिनिरूपणम्)

(४०५ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ आदिरन्त्येन सहेतेत्यसंप्रत्ययः संज्ञिनोऽनिर्देशात् ॥ * ॥

(भाष्यम्)

आदिरन्त्येन सहेतेति असंप्रत्ययः ॥
किं कारणम् ?
'संज्ञिनोऽनिर्देशात्' । न हि संज्ञिनो निर्दिश्यन्ते ॥

(**प्रदीपः**) **आदिरन्त्येन०** ॥ ७१ ॥ **असम्प्रत्यय इति** । अप्रतिपत्तिरित्यर्थः ॥

(४०६ न्यासान्तरेण समाधानवार्तिकम् ॥ २ ॥)

॥ * ॥ सिद्धं त्वादिरिता सह तन्मध्यस्येति वचनात् ॥ * ॥

(भाष्यम्)

सिद्धमेतत् ॥
कथम् ?

आदिरन्त्येनेता सह गृह्यमाणः स्वस्य च रूपस्य ग्राहकः, तन्मध्यानां चेति वक्तव्यम् ॥

(४०७ यथान्यासेनैव समाधानवार्तिकम् ॥ ३ ॥)

॥ * ॥ संबन्धिशब्दैर्वा तुल्यम् ॥ * ॥

(भाष्यम्)

संबन्धिशब्दैर्वा तुल्यमेतत् ॥

कथम् ?

तद्यथा—संबन्धिशब्दाः—मातरि वर्तितव्यम्, पितरि शुश्रूषितव्यमिति । न चोच्यते—स्वस्यां मातरि, स्वस्मिन् पितरीति । संबन्धाच्च गम्यते—या यस्य माता, यो यस्य पितेति । एवमिहापि 'आदिः' 'अन्त्यः' इति संबन्धिशब्दावेतौ । तत्र संबन्धादेतद्गन्तव्यम्—यं प्रति य आदिः-अन्त्य इति च भवति तस्य ग्रहणं भवति, स्वस्य च रूपस्येति ॥ आदिरन्त्येन सहेता ॥ ७१ ॥

(प्रदीपः) सम्बन्धिशब्दैर्वेति । संज्ञयैवाक्षिप्तः संज्ञीत्यर्थः । आद्यन्तौ च मध्यापेक्षाविति मध्यमानामेव संज्ञित्वम् ॥ स्वंरूपमित्यनुवर्तनात्स्वरूपस्य च । सहग्रहणाच्चाद्यन्तौ समुदितौ संज्ञेतीको यणचीति समुदायादेव विभक्तेरुत्पत्तिः, नादिमात्रात् । स्वंरूपं त्वादेरेव गृह्यते नान्त्यस्य, तस्याप्राधान्यादिति 'दध्यत्र' इति केवल एव यकार आदेशः प्रवर्तते, न तु णकारसहितः ॥ ७१ ॥

(उद्द्योतः) आदिरन्त्ये० ॥ ७१ ॥ संज्ञयैवेति । संज्ञाबोधकेनान्त्यसमभिव्याहृतेच्छब्दसहितादिशब्देनेत्यर्थः ॥ आक्षेपप्रकारमाह—आद्यन्तौ चेति । यद्यप्यादिशब्दः परमात्रमपेक्षते, अन्तश्च पूर्वमात्रम्, तथापि सह प्रयुज्यमानौ मध्यापेक्षाविति भावः ॥ मध्यमानामेवेत्येवकारः सौलभ्यद्योतकः ॥ स्वंरूपमित्यनुवर्तनादिति । अन्ये तु—आद्यन्तशब्दाभ्यामवयववाचकाभ्यामवयवी समुदाय आक्षिप्त इति संबन्धित्वेनाविशेषादादेरपि ग्रहणम् । अन्त्यस्य तु न, 'आचारादप्रधानत्वाल्लोपश्च बलवत्तरः' इत्युक्तेरन्यानुबन्धानामिवास्यापि संज्ञाकार्याभावात् । स्वशब्देन विशेषणीभूतान्त्यमात्रपरामर्शासम्भवेऽपि विशिष्टपरामर्शे बाधकाभावेन तथा युक्त्या न निर्वाहः । एतत्फलितार्थकथनमेव भाष्ये—स्वस्य च रूपस्येति । तेन चाद्यन्तशब्दौ पूर्वपरशब्दवन्नावधिमच्छब्दौ, किंत्ववयवशब्दाविति सूचयतीत्याहुः ॥ समुदायादेवेति । तस्यैव संज्ञिनाऽर्थेनार्थवत्तया प्रातिपदिकत्वादिति भावः ॥ ननु स्वंरूपमित्यस्यानुवृत्तावन्त्यसहितादेर्विशिष्टस्य यणिति रूपस्य संज्ञित्वे दध्यत्रेत्यादौ णकारसहितः स्यादत आह—स्वंरूपं त्विति ॥ अत्र वदन्ति—समुदितस्य संज्ञात्वे "प्रत्याहारेष्वाद्या वाचकास्तत्र ग्रहणकशास्त्रं सावकाशं" इति ग्रहणकसूत्रस्थभाष्यविरोधः । टिघुभाद्येकदेशवदस्यापि ग्राहकत्वप्रसक्त्यभावात् । तस्मादाद्यवर्ण एव वाचकता, अन्त्यस्तु तात्पर्यग्राहकः । सहग्रहणात्तु विशिष्टे तदारोपाद्विशिष्टाद्विभक्त्युत्पत्तिरिति द्योतकान्तरवैयर्थ्यमिति ॥ ७१ ॥

(९६ तदन्तसंज्ञासूत्रम् ॥ १ । १ । ९ आ. १२. सू०)

येन विधिस्तदन्तस्य ॥ १ । १ । ७२ ॥

(तदन्तविधिविषयनिर्णयः)

(आक्षेपभाष्यम्)

इह कस्मान्न भवति—"इको यणचि" । दध्यत्र, मध्वत्र ?

(प्रदीपः) येन० ॥७२॥ इह कस्मादिति । शब्दानुशासनप्रस्तावाच्छब्दस्तदरूपमिका विशेष्यत इत्यस्ति तदन्तस्य प्रसङ्गः ॥

(उद्द्योतः) येन विधिः० ॥ ७२ ॥ ननु येनेति करणे तृतीया, न कर्तरि, पष्ठ्यापत्तेः । शास्त्रे करणं च विशेषणमेवेत्यग्रे भाष्यकृद्वक्ष्यति । तदन्तस्य-इति बहुव्रीहिः । एवं चेको यणित्यादौ विशेष्याभावात् कथमतिव्याप्तिरत आह—शब्दानुशासनेति । वस्तुतोऽस्यार्थस्य भाष्येऽग्रे वक्ष्यमाणत्वान्नैतं पूर्वपक्षी जानातीति विशेष्यप्रदर्शनं व्यर्थम् ॥ यत्संबन्धी विधिः स तदन्तस्य संज्ञेति सूत्रार्थं मत्वा शङ्का । अत एवाग्रे विधेयेनापि तदन्तविधिं वक्ष्यति । विधिः-इति च भावे किः । सौत्रत्वाच्च तृतीयेत्याहुः ॥

(समाधानभाष्यम्)

अस्तु । अलोऽन्त्यस्य विधयो भवन्तीत्यन्त्यस्य भविष्यति ॥

(अनिष्टापत्तिभाष्यम्)

नैवं शक्यम् । ये अनेकाल आदेशास्तेषु दोषः स्यात्—"एचोऽयवायावः" इति ॥

(प्रदीपः) येऽनेकाल इति । ततश्च चयनजयनादिष्वयनमिति प्राप्नोति । प्रकरणादिवशाच्चाक्षादिष्विवार्थविशेषावगतिः स्यात् । निर्दिश्यमानस्यादेशा इति अत्र नाश्रितं परिहारान्तरविवक्षया ॥

(उद्द्योतः) नन्वयनमित्यादितश्चयनमित्याद्यर्थावबोधात्, अर्थाभिधानयोग्यस्यैवादेशत्वात्कथमत्रादेशोऽत आह—प्रकरणेति ॥

(अनिष्टापत्तिनिराकरणभाष्यम्)

नैष दोषः । यथैव प्रकृतितस्तदन्तविधिर्भवति, एवमादेशतोऽपि भविष्यति । तत्रैजन्तस्यायाद्यन्ता आदेशा भविष्यन्ति ॥

(उद्द्योतः) भाष्ये—यथैवेति । एना तदन्तविधावयादेः कार्यत्वम्, अयादेस्तु तदन्तविधौ साधुत्वस्यायादिना बोध्यमानतया कार्यत्वमिति विवेकः ॥

(आक्षेपभाष्यम्)

यदि चैव कश्चिद्द्वैरूप्यं तत्र दोषः स्यात् ॥

(प्रदीपः) यदि चैवेति । 'आद्गुणः' इत्यादौ । अत्र हि 'आत्' इत्यकारान्तो गृह्यते । 'अचि' इति चाजादिः । तेन खट्वेन्द्र इत्यादाववर्णान्तस्य समुदायस्याजादेश्च गुणप्रसङ्गाद्द्वैरूप्यप्रसङ्गः । षष्ठीनिर्देशाच्च निर्दिश्यमानस्येत्यपि नास्ति ॥

(उद्द्योतः) अजादिरिति । यस्मिन्विधिरिति परिभाषणादिति भावः ॥ षष्ठीनिर्देशादिति । पूर्वपरयोरिति षष्ठी तु साधार-

णीति भावः ॥ तदादितदन्तविध्युपस्थितिसामर्थ्याच्च तदप्रवृत्तिर्बोध्या ॥ अत एवालोऽन्त्यस्येत्यादेरप्रवृत्तिरित्याहुः ॥

(आक्षेपान्तरभाष्यम्)

अपि चान्तरङ्गबहिरङ्गे न प्रकल्पेयाताम् ॥

तत्र को दोषः ?

स्योनः, स्योना । अन्तरङ्गलक्षणस्य यणादेशस्य बहिरङ्गलक्षणो गुणो बाधकः प्रसज्येत । ऊनशब्दमाश्रित्य यणादेशः, नशब्दमाश्रित्य गुणः ॥

(प्रदीपः) **स्योन इति** । सिवेर्बाहुलकादौणादिके नप्रत्यये गुणो वलोप ऊठ्-इति कार्यत्रयस्य प्रसङ्गः । तत्रापवादत्वादूठा वलोपो बाध्यते, गुणस्त्वन्तरङ्गत्वाद्बाध्यते । गुणो ह्यङ्गसंबन्धिनीमिग्लक्षणां लघ्वीमुपधामार्धधातुकं चाश्रयति, ऊठ् तु वकारान्तमङ्गमनुनासिकादिकं च प्रत्ययमित्यल्पापेक्षत्वादन्तरङ्गः । तत्र कृते गुणश्च प्राप्नोति यणादेशश्च । तत्र वर्णमात्रापेक्षत्वाद्यणादेशोऽन्तरङ्गः प्रवर्तते । नानाश्रयत्वाद्वार्णादाङ्गं बलीय इत्येतन्नास्ति । यत्रैकाश्रये आङ्गवार्णे यथा कार इति घञाश्रये यण्वृद्धी तत्रैवास्य प्रवृत्तिः । यदि च **इको यणची**त्यत्र तदन्ततदादिविधी स्यातां तदा यणादेशस्यान्तरङ्गत्वाभावात् परत्वाद्गुणः स्यात् ॥ **अन्तरङ्गलक्षणस्येति** । असति तदन्ततदादिविधित्वे योऽन्तरङ्गस्तस्येत्यर्थः ॥ एवं बहिरङ्गलक्षणो गुण इति व्याख्येयम् ॥

(उद्द्योतः) भाष्ये—**अन्तरङ्गबहिरङ्गे इति** । वर्णमात्राश्रयत्वेन वार्णस्यान्तरङ्गत्वमिष्यते, तदपि चेत्समुदायस्य, न कोऽपि विशेषः स्यादिति भावः ॥ **अन्तरङ्गलक्षणस्ये**त्यस्य तत्त्वाभिमतस्येत्यर्थः ॥ **बाधक** इत्यस्य-तव मते उभयोः समत्वेन परत्वादिति शेषः ॥ **गुणः—पुगन्तेत्यनेन** ॥ **गुणो हीति** । इकारस्येति शेषः ॥ गुणः पञ्चकाश्रयः, ऊठ् तु चतुष्काश्रय इति विवेकः ॥ **नानेति** । अचि-यण, प्रत्यये-गुण इति भावः । **इदं चिन्त्यम्**, इयायेत्यायसिद्धेः, ज्ञापकासंभवाच्च ॥ केचित्त्वत्रापि तदादितदन्तविधावस्य वार्णत्वाभावात्तदप्रवृत्तिः, सा वक्तुं चाशक्या वार्णाप्रसिद्धेरिति भाष्याशयः ॥ यद्वा तदप्रवृत्तिरनित्यत्वादुभयसंमतेति भाष्याशय इत्याहुः ॥ व्याहृतिं निराकरोति—**असतीति** । सति तु तस्मिन्नान्तरङ्गत्वमिति भावः ॥ इदं तु बोध्यम्—एवमपीगन्तशब्दाजादिशब्दमात्रापेक्षत्वं यणः, गुणस्य तूक्तरीत्या पदार्थपञ्चकापेक्षत्वमिति कथं न बहिरङ्गत्वम् । तस्मात्संज्ञापेक्षं न बहिरङ्गम् । गुणादूठ् तु नित्यः । सिद्धान्ते ऊठि कृते यणा बाधाद्गुणो न नित्यः । इदानीं तदसिद्धिरपि दोष इति भाष्याशय इति ॥ **एवमिति** । सति तदादितदन्तविधित्वे यणा तुल्यनिमित्त इति न स बहिरङ्ग इति भावः ॥ भाष्ये-**ऊनशब्दमाश्रित्ये**त्यादिना यणो बहिरङ्गत्वं गुणस्यान्तरङ्गत्वं दर्श्यते । एवं च **परत्वाद् गुणः स्यादिति कैयटश्चिन्त्यः** । अनेन हि भाष्येण परिभाषायामङ्गशब्दो निमित्तपरो, न तु स्थान्यादिपरोऽपीति सूचयति । यणिनिमित्तोनशब्दावयवत्वेन नशब्दस्य ततो बहिष्ट्वाभावः । गुणनिमित्तनशब्दादूनशब्दस्य बहिर्भूतोकारघटितत्वाद्यणो बहिरङ्गत्वमिति भावः ॥

(आक्षेपान्तरभाष्यम्)

अल्विधिश्च न प्रकल्पेत—द्यौः, पन्थाः, स इति ॥

(प्रदीपः) **अल्विधिरिति** । अलोऽन्त्यस्येत्यत्रापि तदन्तविधिसद्भावादन्त्यालन्तस्य समुदायस्य कार्येण भाव्यमिति द्यौः पन्था इत्यात्रा**लोऽन्त्यस्या**देशो न प्राप्नोतीत्यर्थः ॥ तत्र कदाचित्पथिमित्यस्याकारः स्यात्, कदाचित् थिन्नित्यस्य । **अनेकाल् शित्सर्वस्ये**त्येतत्तु सर्वस्यैवेति नियमार्थं स्यात् ॥

(उद्द्योतः) भाष्ये—**अल्विधिश्चेति** । स्थानिवदित्यत्र अलो जायमानो विधिरल्विधिरित्यर्थः ॥ **अलोऽन्त्यस्यादेशो नेति** । नियमेनेति शेषः ॥ **थिन्नित्यस्येति** । कदाचित् 'इन्नित्यस्य' इत्यपि बोध्यम् ॥ सर्वथाऽऽदेशस्य स्थानिवत्त्वात्सुलोपः स्यादिति भावः ॥ नन्वेवमनेकाल्शिदिति व्यर्थं कदाचिदेकाल्वत् तस्यापि सर्वादेशत्वसिद्धेरत आह—**अनेकालिति** ॥ **सर्वस्यैवेति** । षष्ठीनिर्दिष्टसर्वस्यैवेत्यर्थः ॥

(न्यासान्तरोपसंहारभाष्यम्)

तस्मात्—

"प्रकृते तदन्तविधिः"

इति वक्तव्यम् ॥

(प्रदीपः) **प्रकृत इति** । प्रस्तुते । प्रस्तावश्च क्वचित्साक्षात् तदन्तविधिभाजो निर्देशात् यथा—**ईदूदेद्द्विवचनं प्रगृह्यम्**इत्यत्र द्विवचनस्य । क्वचिदधिकारात् यथा—**पर**-जित्यत्र धातोः । क्वचिदाक्षेपात् यथा—**इको झलि**त्यत्र सना धातोः ॥

(उद्द्योतः) प्रकृतं नाम पूर्वत्र निर्दिष्टमनुवर्तमानं चेत् **ईदूदेद्द्विवचन**मित्यत्र तदन्तविधिर्न स्यादत आह—**प्रस्तुत इति** । प्रस्तावश्च बुद्धिसंनिधिः ॥ भाष्ये—प्रस्तुत इत्यर्थकप्रकृते इत्यस्य विशेष्ये इति शेषः ॥ **तदन्तविधिभाज इति** । तदन्तश्चासौ विधिभाक्चेति कर्मधारयः । तदन्तशब्दे च बहुव्रीहिरिति बोध्यम् ॥ शब्दरूपविशेष्यमादाय तु अस्य सर्वत्र न प्रवृत्तिरव्यावर्तकत्वादिति भावः ॥

(न्यासान्तरनिराकरणभाष्यम्)

न वक्तव्यम् । 'येन' इति करण एषा तृतीया । अन्येन चान्यस्य विधिर्भवति । तद्यथा—देवदत्तस्य समाशं शरावैरोदनेन च यज्ञदत्तः प्रतिविधत्ते । तथा—संग्रामं हस्त्यश्वरथपदातिभिः । एवमिहाप्यचा धातोर्यतं विधत्ते । अकारेण प्रातिपदिकस्य इञं विधत्ते ॥

(प्रदीपः) **करण एवेति** । विधिशब्दः कर्मसाधनः । येन करणेन कार्यं विधीयते स शब्दस्तदन्तस्य संज्ञेत्यर्थः । तेन विशेषणेन विशेष्यस्य तदन्तविधिः, नान्यथा । **इको यणची**त्यादौ च विशेष्यस्यासन्निधानात्तदन्तविधेरभावः ॥ **हस्त्यश्वरथपदातिभिरिति** । बहुप्रकृतित्वाभावादेकवद्भावाभावः ॥

(उद्द्योतः) **कर्मसाधन इति** । भावसाधनत्वेऽपि न बाधकं, प्रसिद्धत्वादेव विधेयं कर्म लभ्यते ॥ **स शब्द इति** । इह शास्त्रे प्रायः शब्दस्यैव कार्यकरणत्वादिति भावः ॥ **तेन विशेषणेनेति** । कार्यविधाविति शेषः ॥ विशेषणत्वलाभोऽत्रैवम्—करणस्य व्यापारवत्त्वनियमादन्येषां च व्यापाराभावाद्विशेषणमेवात्र करणशब्देनोच्यते । तस्य चेतरव्यावृत्तिकरणमेव व्यापार इति भावः ॥ तैत्र प्रत्यासत्त्या शब्दप्रयोज्योपस्थितिविषयं विशेषणमेव प्रायेण तदन्तग्राहकमितीको

यणचीत्यादौ न दोषः ॥ कचित्तु सति गमकेऽतादृशं शब्दरूपविशेष्यमादायापि तदन्तविधिरिति भावः ॥ तदप्यन्तरङ्गत्वात्समानाधिकरणविशेषणमेवेति बोध्यम् ॥ भाष्ये—**अन्येन चान्यस्येति** । अनेन यस्य कार्यं - यस्मिन्परतः, तयोरकरणत्वं दर्शितम् । अन्यस्येत्यन्यस्मिन्नित्यस्याप्युपलक्षणम् । **समाशो भोजनम्** ॥ सेनाङ्गत्वादेकवत्त्वं प्राप्नोतीत्यत आह—**बह्विति** । बह्वर्थवाचिपूर्वोत्तरपदकत्वाभावाद्द्वन्द्वस्येत्यर्थः ॥

(विशेषणविशेष्यभावयोर्यथेष्टत्वम्)

(४०८ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ येन विधिस्तदन्तस्येति चेद् ग्रहणोपाधीनां तदन्तोपाधिप्रसङ्गः ॥ * ॥

(भाष्यम्)

येन विधिस्तदन्तस्येति चेद् ग्रहणोपाधीनां तदन्तोपाधिताप्रसङ्गः । ये ग्रहणोपाधयस्तेऽपि तदन्तोपाधयः स्युः ॥

तत्र को दोषः ?

"उतश्च प्रत्ययादसंयोगपूर्वाद्" इति असंयोगपूर्वग्रहणमुकारान्तविशेषणं स्यात् ॥

तत्र को दोषः ?

असंयोगपूर्वग्रहणेन इहैव पर्युदासः स्यात्—अक्षणुहि, तक्षणुहीति । इह न स्यात्—आप्नुहि, शक्नुहीति ॥

तथा "उदोष्ठ्यपूर्वस्य" इति ओष्ठ्यपूर्वग्रहणमृकारान्तविशेषणं स्यात् ॥

तत्र को दोषः ?

ओष्ठ्यपूर्वग्रहणेन इह च प्रसज्येत—संकीर्णम्—इति । इह च न स्यात्—निपूर्ताः पिण्डा इति ॥

(प्रदीपः) **ग्रहणोपाधीनामिति** । गृह्यते=उच्चार्यत इति ग्रहणं, तस्य ये उपाधय इष्यन्ते ते तदन्तस्य संज्ञिनः प्राप्नुवन्ति । संज्ञा हि संज्ञिप्रत्यायने विशेषणभावमापन्ना कथमात्मनो विशेषणसंबन्धमनुभवेत् ॥ **सङ्कीर्णमिति** । ओष्ठ्यः पूर्वो यस्मादृकारान्ताद्धातोः, तस्योत्त्वमित्येव सूत्रार्थः स्यात् । अत्र च सूत्रार्थे धात्ववयवत्वमोष्ठ्यस्याश्रयितुं न युज्यते, अवधित्वावयवित्वयोरेकस्य विरोधात् ॥

(उद्योतः) तस्य—गृह्यमाणस्य ॥ **उपाधय इति** । विशेषणानीत्यर्थः ॥ **प्राप्नुवन्ति**—उपाधय इत्यनुकर्षः ॥ वार्तिके—**तदन्तोपाधी**ति भावप्रधानो निर्देश इति बोध्यम् ॥ तदन्तसंज्ञायामप्युकारस्यास्तु विशेषणेन संबन्धो विरोधाभावादत आह—**संज्ञा हीति** ॥ **विशेषणभावम्**-गुणभावम् ॥ यद्वा—संज्ञिप्रत्यायने - तद्बोधे सति विशेषणत्वमापन्नेत्यर्थः ॥ **आत्मनेति** पाठे स्वयमित्यर्थः । आत्मनीत्यर्थो वा ॥ **आत्मन** इति पाठे तु सम्यगेव । **गुणानां च परार्थत्वात्पदार्थैकदेशत्वाच्चे**ति न्यायादिति भावः ॥

अवधित्वेति । अवधित्वं च तदनारम्भकत्वे सति पञ्चम्यन्तपदवाच्यत्वरूपं पूर्वादियोगे । अवयवत्वं च तदारम्भकत्वमिति ते एकं प्रत्येकस्य न संभवत इत्यर्थः । ओष्ठ्यः पूर्वो यस्मादिति विग्रहे एव दोषः । षष्ठ्यर्थे बहुव्रीहौ तु यद्यपि पूर्वशब्दस्य प्रथमावयववाचित्वाद्धात्ववयवत्वमोष्ठ्यस्य लभ्यत इति नायं दोषस्तथापि गुस्पूर्वतीत्यादौ दोषो बोध्यः ॥ एवमुतश्चेति सूत्रे पूर्वशब्दस्यावयववाचित्वे प्रत्ययविशेषणत्वासंभवः, संयोगपूर्वकोकारान्तप्रत्ययाभावेनाव्यावर्तकतयाऽसंयोगपूर्वादिति निषेधवैयर्थ्यापत्तेः । न चाङ्गविशेषणत्वम्, क्षणु इत्याद्यसिद्धेः ॥ अतो व्यवस्थावाची पूर्वशब्दः श्रूयमाणप्रत्ययविशेषणम् । तदुक्तं भाष्ये—**पूर्वग्रहणमुकारान्तविशेषणमिति** । न चासंयोगादिति वक्तव्ये पूर्वग्रहणाद्विशेषणस्याप्युकारस्य विशेषणमिति न दोष इति वाच्यम् । वाच्यवृत्त्याऽलाभात् । किं च व्यवहिते क्षिणु इत्यादावपि निषेधार्थं पूर्वग्रहणं स्यादिति भावः ॥ भाष्ये—**निपूर्ता** इत्यत्र न ध्याख्येति नत्वनिषेधः ॥

(४०९ समाधानवार्तिकम् ॥ २ ॥)

॥ * ॥ सिद्धं तु विशेषणविशेष्ययोर्यथेष्टत्वात् ॥ * ॥

(भाष्यम्)

सिद्धमेतत् ॥

कथम् ?

यथेष्टं विशेषणविशेष्ययोर्योगो भवति ।

यावता यथेष्टम् । इह तावत्—"उतश्च प्रत्ययादसंयोगपूर्वात्" इति नासंयोगपूर्वग्रहणेन उकारान्तं विशेष्यते ॥

किं तर्हि ?

उकार एव विशेष्यते—उकारो योऽसंयोगपूर्वः, तदन्तात्प्रत्ययादिति ॥

तथा—"उदोष्ठ्यपूर्वस्य" इति नौष्ठ्यपूर्वग्रहणेन ऋकारान्तं विशेष्यते ॥

किं तर्हि ?

ऋकार एव विशेष्यते—ऋकारो य ओष्ठ्यपूर्वः, तदन्तस्य धातोरिति ॥

(प्रदीपः) **सिद्धं त्विति** । वृद्ध्यादिसंज्ञा गुणप्रधानभावानपेक्षा एव प्रदेशेषु संज्ञिनः प्रत्याययन्ति । इयं तु संज्ञा गुणप्रधानभावापेक्षत्वात्कार्यकाला । तत्रोतश्च प्रत्ययादित्यादौ विशेषणसंबन्धमनुभूय विशेष्येण संबन्धमुकारादिरनुभवतीति यथोक्तदोषाभावः ॥

(उद्योतः) विशेषणविशेष्यभावे कामचारेऽपि **संज्ञासूत्रस्य** प्रबलत्वात्पूर्वं तदन्तविधिरेव स्यादत आह—**वृद्ध्यादीति** । एवं च विशेषणत्वज्ञानसापेक्षतयाऽवान्तरवाक्यार्थबोधोत्तरमेव प्रवृत्त्या बहिरङ्गत्वादस्य पूर्वमुकारादीनामेव तद्विशेषणमिति भावः ॥ **गुणप्रधानभावानपेक्षा इति** । एवं च तत्र वाक्यभेद एवेति भावः ॥ **इयं त्विति** । तदपेक्षत्वाद् विधिवाक्यैकवाक्यतापन्नेवेत्यर्थः ॥ यदुक्तम्—संज्ञा हीति, तत्राह—**तत्रे**ति । गुणः कृतात्मसंस्कारः प्रधानोपकाराय महते-प्रभवतीति न्यायादिति भावः ॥ भाष्ये—**यथेष्ट-**

मिति । विशिष्टे वैशिष्ट्यम्, विशिष्टस्य वैशिष्ट्यम्, विशेष्ये विशेषणं तत्र च विशेषणान्तरम्, एकत्र द्वयमिति योगेषु यथेष्टमित्यर्थः ॥ एवं च व्याख्यानात्मकत्वे विशिष्टस्य वैशिष्ट्यमिति रीत्यैव बोधो न तु विशेष्ये विशेषणमित्यादिरीत्येति तात्पर्यम् ॥

(तदन्तसंज्ञाप्रतिषेधः)

(४१० आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ समासप्रत्ययविधौ प्रतिषेधः ॥ * ॥

(भाष्यम्)

समासविधौ प्रत्ययविधौ च प्रतिषेधो वक्तव्यः ॥

समासविधौ तावत्—द्वितीया श्रितादिभिः समस्यते—कष्टश्रितः, नरकश्रितः । कष्टं परमश्रित इत्यत्र मा भूत् ॥

प्रत्ययविधौ—"नडादिभ्यः फक्", नडस्यापत्यं नाडायनः । इह न भवति—सूत्रनडस्यापत्यं सौत्रनाडिः ॥

(प्रदीपः) **समासेति** । श्रितादिभिः सुबन्तस्य विशेषणे सति प्राप्तस्तदन्तविधिः प्रतिषिध्यते । प्रतिषेधद्वारेण चैतत् प्रदर्श्यते—श्रितादयः प्राधान्येनाश्रयितव्याः, तद्विशेषणत्वेन च सुपा-इति ॥ **कष्टं परमश्रित इति** । श्रितान्तमेतत् सुबन्तं न भवतीति संबुद्ध्यन्तमुदाहर्तव्यम्—परमश्रितेति । एतत् प्रत्ययलक्षणेन सुबन्तं भवति, श्रितान्तं च श्रूयते ॥ **सौत्रनाडिरिति** । अनुशतिकादित्वादुभयपदवृद्धिः । नडादीनि प्रातिपदिकेन विशेष्यन्त इति तदन्तविध्यभावः ॥

(उद्द्योतः) **सुबन्तस्येति** । सुपेत्युपस्थितस्येति शेषः ॥ **तद्विशेषणत्वेनेति** । सुबन्तैः श्रितादिभिरित्यर्थ इति भावः ॥ **श्रितान्तमिति** । विसर्गान्तस्य तदन्तत्वाभावादिति भावः ॥ **संबुद्ध्यन्तमिति** । इदमुपलक्षणम्—कष्टं परमश्रिता - इत्यादेः ॥ **तदन्तविध्यभाव इति** । नडादीनां विशेष्यत्वात्प्रातिपदिकस्य विशेषणत्वेऽपि तदन्तस्य नडादेरसंभवादिति भावः ॥ अत्र वदन्ति—एवं हि कृष्णश्रितमित्यादेरप्यसिद्धिरिति भाष्यस्य निर्दलत्वापत्तिः ॥ यत्तु सुप्सहितैः श्रितादिभिरिति विवरणकृतसिद्धान्ताशयवर्णनम् । तन्न, पूर्वकालैकेत्यादौ सुप इति प्रथमान्ततयाऽर्थासंभवात् । तस्मात् समर्थपरिभाषोपस्थितसमर्थपदार्थं प्रति विशेषणतया प्राप्ततदन्तविधेर्निषेधार्थमिदमिति भाष्याशयः ॥ उपस्थितसमर्थपदं च सत्रीयतत्तत्पदोत्तरविभक्तिसमानविभक्त्यन्तम् । तस्य च तत्प्रकृतिके लक्षणया गदेत्यनेनान्वयः । नं हि सामर्थ्यं सुबन्तेनैवेति नियमः, कुम्भकार इत्यादौ सुपः प्राग्भागेऽपि तदङ्गीकरात् । परिपूर्णं पदमिति न्यायस्तु यस्येतरत्राकाङ्क्षयाऽन्वयस्तद्विषयः, न तु यत्रान्वयस्तद्विषय इति कुरिसत इति सूत्रभाष्यात् स्पष्टमेवोपलभ्यते इति दिक् ॥

(प्रत्याक्षेपभाष्यम्)

किमविशेषेण ?

(समाधानभाष्यम्)

नेत्याह ॥

(४११ आक्षेपपरिशेषवार्तिकम् ॥ २ ॥)

॥ * ॥ उगिद्वर्णग्रहणवर्जम् ॥ * ॥

(भाष्यम्)

उगिद्ग्रहणं वर्णग्रहणं च वर्जयित्वा ॥

उगिद्ग्रहणम्—"उगितश्च" । भवती, महती, अतिभवती, अतिमहती ॥

वर्णग्रहणम्—"अत इञ्" । दाक्षिः, प्लाक्षिः ॥

(प्रदीपः) **अतिमहतीति** । महान्तमतिक्रान्तेति प्रादिसमासः । तत्र यद्यपि गौरादिषु बृहत् महदिति पठ्यते, तथापि अनुपसर्जनाधिकारात् तत्र ङीष् न भवतीति उगिल्लक्षणो ङीप् प्रार्थ्यते ॥ अन्ये तु गौरादिष्वनयोः प्रमादपाठमाहुः । तथा चोक्तम्—*नद्यजाद्युदात्तत्वे बृहन्महतोरुपसंख्यानमिति । ङीषि हि सति उदात्तस्य सिद्धत्वात् किं नद्या उदात्तविधानेन ॥ **अत इति** । तदन्तविधावसति ञित्करणमुत्तरार्थं स्यात् ॥

(उद्द्योतः) **तत्र यद्यपीति** । एवं च ङीषभावेऽपि ङीपा सिद्धिरिति भावः ॥ **किं नद्या इति** । सत्यपि पाठे उपसर्जने ङीपप्राप्तौ ङीपि तस्योदात्तत्वाय तच्चारितार्थ्याच्चिन्त्यमिदम् ॥ एवं च तस्यावश्यकत्वे पाठो निष्फल इत्यन्यदिति कश्चित् ॥ ननु इञो ञित्त्वाद्वृद्धिस्वराद्यर्थोऽत् तदन्तविधिस्तत्र, न हि अशब्दस्य यस्येति चेति लोपे तेषां संभवोऽस्तीत्यत आह—उत्तरार्थमिति । बाहविरित्यादौ स्वरादिसिद्धये इति भावः ॥

(आक्षेपभाष्यम्)

अस्ति चेदानीं कश्चित्केवलोऽकारः प्रातिपदिकं, यदर्थो विधिः स्यात् ॥

(समाधानभाष्यम्)

अस्तीत्याह । अततेर्डः—अः, तस्यापत्यम् "अत इञ्"—इः ॥

(तन्मध्यपतितन्यायः)

(आक्षेपे भाष्यवार्तिकम्)

॥ अकच्स्वरवतः सर्वनामाव्ययधातुविधावुपसंख्यानं कर्तव्यम् ॥

(भाष्यम्)

अकज्वतः—सर्वके, स्वके । अव्ययविधौ—उच्चकैः, नीचकैः ॥

श्नम्वतः—भिनत्ति, छिनत्ति ॥

किं पुनः कारणं न सिध्यति ?

इह—तस्य वा ग्रहणं भवति, तदन्तस्य वा । न चेदं तत्, नापि तदन्तम् ॥

(प्रदीपः) **सर्वक इति** । अकचि कृते शीभावो न स्यात् ॥ **उच्चकैरिति** । अथवा चि कृते लुम स्यात् । उच्चकैरधीयानेति अव्ययानां प्रतिषेध इति परवद्भावनिषेधो न

स्यात् ॥ उच्चकैर्मुखमिति नाव्ययदिक्शब्देति मुखस्वरनिषेधो न स्यात् । भिनत्तीति । धातोरन्त उदात्तो भवतीति उदात्तत्वं न स्यात् । प्रत्ययस्वरेण तु तत्सिध्यतीत्यभिनोत्रेऽति दश्चेति धातोर्विधीयमानं रुत्वं न स्यादिति वक्तव्यम् ॥

अन्ये त्वाहुः—भिनत्तीत्यत्रागमानुदात्तत्वेन प्रत्ययस्वरस्य बाधितत्वात् सतिशिष्टः स्वरो धातुस्वर एष्टव्यः ॥

(उद्द्योतः) अकचीति । 'सर्वे जस्' इति स्थितेऽन्तरङ्गानपीति न्यायेन शीभावादि बाधित्वाऽकचि यस्मात्प्रत्ययविधिरित्युक्तेः प्रत्यय इति निषेधाभावे प्रातिपदिकत्वेन सुपो लुकि पुनर्जसि शी न स्यादित्यर्थः ॥ लुगिति । यद्यपि हल्ङ्यादिसूत्रेणापि सोर्लोपः सिध्यति, तथापि सर्वविभक्त्युत्पत्तिपक्षे - इदम् ॥ पराङ्गेति । तथा चामन्त्रिताद्युदात्तत्वं स्यात्, चितः सप्रकृतेरित्यन्तोदात्तश्चेष्यत इति भावः ॥

अन्ये त्वाहुरिति । श्नमो मित्त्वेन परश्लेलस्य तत्राप्रवृत्तौ तत्संनियोगशिष्टाद्युदात्तत्वाप्रवृत्त्या शेषंनिघातेन तस्यानुदात्तत्वप्राप्तिरिति भावः ॥ ननु भिनत्तीत्यादौ यदागमा इति न्यायेन न दोष इति चेन्न । अवयवानामवयविग्रहणेन ग्रहणं हि तद्बीजम् । न चात्र तदस्ति, अन्तावयव इत्यंशस्याप्रवृत्त्याऽवयवत्वे मानाभावात् । यस्य विहितस्तदन्तावयव इति तदर्थात् । एवं च 'नन्दति' इत्यपि तदुदाहरणं बोध्यम् ॥ भाष्ये च श्नम्वत इत्युपलक्षणं बोध्यमिति कश्चित् ॥

(४१२ समाधानबाधकवार्तिकम् ॥ १ ॥)

॥ * ॥ सिद्धं तु तदन्तान्तवचनात् ॥ * ॥

(भाष्यम्)

सिद्धमेतत् ॥

कथम् ?

'तदन्तान्तवचनात्' । तदन्तान्तस्येति वक्तव्यम् ॥

किमिदं तदन्तान्तस्येति ?

तस्यान्तस्तदन्तः, तदन्तोऽन्तो यस्य तदिदं - तदन्तान्तं, तदन्तान्तस्येति ॥

(प्रदीपः) सिद्धं त्विति । सर्वशब्दस्य योऽन्तोऽकारः सोऽन्तः सर्वकशब्दस्य ॥ एवमन्यत्रापि योज्यम् ॥ तत्र सर्वनामानीत्यन्वर्थसंज्ञाऽऽक्षिप्तः संज्ञी सर्वादिभिर्विशेष्यते, अव्ययसंज्ञाऽऽक्षिप्तः स्वरादिभिः, धातुसंज्ञाभाजो वाप्रकारा भूवादिभिरिति भावः ॥

(उद्द्योतः) ननु तदन्तान्तस्येति पाठेऽपि विशेष्यासंनिधानात् कथं सर्वादीनीत्यादावस्य प्रवृत्तिरत आह—तत्रेति । अव्ययेत्यस्यान्वर्थेत्यादिः ॥ वस्तुतः शब्दरूपं विशेष्यमादाय वाचनिक एवोभयत्रापि तदन्तविधिरिति वक्ष्यते ॥ इदं तु चिन्त्यं–शब्दसंज्ञिनोऽसत्त्वे हि स्यादप्याक्षेपः, सत्त्वे त्वाक्षेपे आक्षिप्तस्य वा विशेष्यत्वे मानाभावात् । किंचान्वर्थत्वं–योगरूढत्वम्, योगरूढस्थले हि योगान्वितरूढ्यर्थस्यैव प्रतीतिर्दृष्टा, न तु तयोः परस्परमुद्देश्यविधेयभाव इति कस्य विशेष्यतया तदन्तविधिः स्यादिति बोध्यम् ॥ वाप्रकारा इति । 'वा' सदृशा इत्यर्थः । भूवादय इति सूत्रे द्वन्द्वैकशेषगर्भो बहुव्रीहिरिति भावः ॥ एवं हि प्रभू पराभू इत्यादीनामपि धातुसंज्ञा स्यादिति अडाद्यव्यवस्थापत्तिरिति चिन्त्यमिदम् ॥ तस्मादयं समाधिरकजिवषय एवेति बोध्यम् ॥ पराजित्यादौ तु व्यपदेशिवद्भावेनैतन्न्यासे सिद्धिर्बोध्या ॥

(तदस्याक्षेपभाष्यम्)

स तर्हि तथा निर्देशः कर्तव्यः ॥

(सिद्धान्तिसमाधानभाष्यम्)

न कर्तव्यः । उत्तरपदलोपोऽत्र द्रष्टव्यः ॥

तद्यथा—उष्ट्रमुखमिव मुखमस्य-उष्ट्रमुखः, खरमुखः । एवमिहापि तदन्तः अन्तो यस्य—तदन्तः, तदन्तस्येति ॥

(प्रदीपः) उत्तरपदलोप इति । वाचनिकोऽत्र लोपः, न तु सामर्थ्याद्गम्यमानार्थस्य निवृत्तिरित्याहुः ॥ अन्ये तु वर्णयन्ति—यथाऽवयवदर्शनाद् गौरित्यवयविविषया बुद्धिरुदेति तथेहापि सर्वशब्दस्य योऽवयवोऽन्त्यस्तत्रैव सर्वशब्दविषयबुद्ध्युत्पादात् तदवयवान्तः सर्वशब्दान्त इति व्यपदिश्यते ॥ अथवा–अवयवे समुदायरूपारोपात् तदन्तता भविष्यति । गौणेनापि ह्यर्थेन शास्त्रे व्यवहारो दृश्यते—छत्रपार्श्वायःशूलदण्डाजिनशीतोष्णार्द्रहस्त्यादिषु ॥

(उद्द्योतः) न तु सामर्थ्यादिति । उष्ट्रमुखवत् तदभावादित्यर्थः ॥ यथाऽवयवेति । अवयवी प्रत्यक्षयवमवयवान्तरसंनिधौ समवेत इति भावः ॥ नन्वेवमपि भूयोऽवयवसंनिकर्षस्यैवावयविप्रत्यक्षे हेतुत्वादेकावयवदर्शने तद्बुद्ध्यभाव इत्यरुचेराह—अथवेति ॥ ननु मुख्यविशेषणे चरितार्थं सूत्रं कथमारोपिते स्यादत आह—गौणेनापीति । स्वरितत्वगुणयोगाद् यथाऽन्यत्रारोपितार्थकस्य ग्रहणं तथेहापीत्यर्थः ॥ तदेवाह—छत्रेत्यादि । छत्रं–गुरुच्छिद्रावरणं गौण्योच्यते । तत्रैव हि छात्र इष्यते । एवं पार्श्वशब्दोऽनृजूपाये, अयःशूलशब्दस्तीक्ष्णोपाये, दण्डाजिनो दम्भे, शीतोऽलसे, उष्णः शैघ्र्ये गौणः । तत्रैव पार्श्वकायःशूलिकदाण्डाजिनिकशीतकोष्णकादिप्रयोगेष्टेः । हस्त्यादित इत्यत्र चार्धहस्तशब्दोऽर्धमात्रालाक्षणिक इत्याद्यूह्यम् ॥ आदिनाऽऽधारोऽधिकरणमित्यादिसंग्रहः ॥

(यथान्यासेऽपि समाधानभाष्यवार्तिकम् ॥)

* ॥ तदेकदेशविज्ञानाद्वा सिद्धम् ॥ *

(भाष्यम्)

तदेकदेशविज्ञानाद्वा पुनः सिद्धमेतत् । तदेकदेशभूतस्तद्ग्रहणेन गृह्यते ॥ तद्यथा—गङ्गा, यमुना, देवदत्तेति । अनेका नदी गङ्गां यमुनां च प्रविष्टा गङ्गायमुनाग्रहणेन गृह्यते । तथा—देवदत्तास्थो गर्भो देवदत्ताग्रहणेन गृह्यते ॥

(प्रदीपः) तदेकदेशविज्ञानादिति । मध्यपातिनोऽकजादयस्तदेकदेशा इति तत्त्वबुद्धिं न विघ्नन्ति ॥

(उद्द्योतः) मध्यपातिन इति । यस्मादकजादिस्तदेकदेशत्वेनाकजादेर्विज्ञानादिति वार्तिकार्थः ॥

(समाधानबाधकभाष्यम्)

विषम उपन्यासः । इह केचिच्छब्दा अकपरिमाणानामर्थानां वाचका भवन्ति—य एते संख्याशब्दाः परिमाणशब्दाश्च । पञ्च, सप्तेति एकेनाप्यपाये न भवन्ति । द्रोणः, खारी, आढकमिति नैवाधिके भवन्ति, न न्यूने ॥

केचिद् यावदेव तद्भवति तावदेवाहुः—य एते जातिशब्दा गुणशब्दाश्च । तैलं घृतमिति खार्यामपि भवन्ति, द्रोणेऽपि ॥ शुक्लो नीलः कृष्ण इति हिमवत्यपि भवति, वटकणिकामात्रेऽपि द्रव्ये ॥

इमाश्चापि संज्ञा अकपरिमाणानामर्थानां क्रियन्ते ताः केनाधिकस्य स्युः ?

(प्रदीपः) अकपरिमाणानामिति । परिच्छिन्नपरिमाणानामित्यर्थः ॥ यावदिति । अल्पमधिकं वेत्यर्थः ॥ इमाश्चापीति । सर्वाद्युपादानेन संज्ञाः क्रियमाणाः कथं सर्वकादीनां भवन्ति । नित्या हि शब्दा विकारोपजनरहिता इति सर्वशब्दः सर्वकशब्द इति न वक्तुं शक्यत इत्यर्थः ॥

(उद्द्योतः) भाष्ये—अकपरिमाणानामिति । अकपरिमाणं—आनुपूर्वीविशेषोऽपि ॥ परिमाणेत्युपलक्षणं परिच्छिन्नार्थानाम् । तदाह—सङ्ख्येति ॥ भाष्ये—अर्थानामिति । संज्ञिभूतानां शब्दानामित्यर्थः ॥ नन्वधिकागद्यादिजननेऽपि शुनः श्वत्ववद् अकस्याधिकस्योपजनेऽपि सर्वकस्य सर्वशब्दत्वमक्षतमेवेत्यत आह—नित्या इति । वस्तुतः परिच्छिन्नपरिमाणकग्रहणे एकदेशविकृतन्यायस्याप्रवृत्तिरिति भाष्याशयः ॥

(समाधानसाधकभाष्यम्)

एवं तर्ह्याचार्यप्रवृत्तिर्ज्ञापयति—

'तदेकदेशभूतं तद्ग्रहणेन गृह्यते' इति ॥

यदयं "नेदमदसोरकोः" इति सककारयोरिदमदसोः प्रतिषेधं शास्ति ॥

कथं कृत्वा ज्ञापकम् ?

इदमदसोः कार्यमुच्यमानं कः प्रसङ्गो यत्सककारयोः स्यात् । पश्यति त्वाचार्यः—'तदेकदेशभूतं तद्ग्रहणेन गृह्यते' इति । ततः सककारयोः प्रतिषेधं शास्ति ॥

(प्रदीपः) एवं तर्हीति । यद्यपि नित्याः शब्दास्तथापि प्रक्रियायामकजादयो विधीयमाना ज्ञापकादव्यतिरेकक्त इत्यर्थः ॥

(उद्द्योतः) ननु नित्यशब्दवादेऽकज्वतः शब्दान्तरत्वादकजादेः सर्वाद्येकदेशत्वमसिद्धमित्यत आह—यद्यपीति ॥ अव्यतिरेकक्त इति । अनवयवत्वेऽपि ज्ञापकात् भेदबुद्धिं न कुर्वन्ति इत्यर्थः ॥ एकदेशत्वाद्वयं च मध्यपातित्वेन बोध्यम् ॥

(तदन्तसंज्ञोदाहरणम्)

(आक्षेपभाष्यम्)

कानि पुनरस्य योगस्य प्रयोजनानि ?

(प्रयोजने भाष्यवार्तिकम्)

॥ प्रयोजनं सर्वनामाव्ययसंज्ञायाम् ॥

(भाष्यम्)

सर्वे, परमसर्वे, विश्वे, परमविश्वे । उच्चैः, परमोच्चैः, नीचैः, परमनीचैरिति ॥

(प्रदीपः) प्रयोजनमिति । अन्वर्थसंज्ञाऽऽश्रितः संज्ञी सर्वादिभिर्विशेष्यते । अपूर्वो वा तदन्तविधिरुपसंख्यायते । एवमुत्तरत्र विज्ञेयम् ॥

(उद्द्योतः) ननु सर्वनामत्वे संज्ञोपसर्जनप्रतिषेधवार्तिकारम्भेण वार्तिककृतोऽन्वर्थत्वं नेष्टम् । किंच संज्ञिनामुपात्तत्वेनाक्षेपे मानाभावः, इत्यत आह—अपूर्वो वेति । एतद्वार्तिकमूलाद् व्याख्यानादव्यावर्तकमपि शब्दरूपं विशेष्यमादाय तदन्तविधिरिति भावः ॥

(प्रयोजने भाष्यवार्तिकम्)

॥ उपपदविधौ भयाढ्यादिग्रहणं प्रयोजनम् ॥

(भाष्यम्)

भयंकरः, अभयंकरः । आढ्यंकरणं, स्वाढ्यंकरणम् ॥

(प्रदीपः) उपपदविधाविति । भयाद्यादिभिः कर्म विशेष्यते । क्षेमप्रियमद्रेऽण् चेत्यत्र तु कर्मणा क्षेमादय इति तदन्तविध्यभावः ॥

(उद्द्योतः) भयं चाढ्यादि चेति द्वन्द्वमभिप्रेत्याह—क्षेमेति ॥

(प्रयोजने भाष्यवार्तिकम्)

॥ ङीब्विधावुगिद्ग्रहणं प्रयोजनम् ॥

(भाष्यम्)

भवती, अतिभवती । महती, अतिमहती ॥

(प्रयोजने भाष्यवार्तिकम्)

॥ प्रतिषेधे स्वस्रादिग्रहणं प्रयोजनम् ॥

(भाष्यम्)

स्वसा, परमस्वसा । दुहिता, परमदुहिता ॥

(प्रदीपः) प्रतिषेध इति । विधीयत इति—विधिः सामान्येन गृह्यत इति ङीप्रतिषेधेऽपि तदन्तविधिर्भवति, स्वस्रादिभिः प्रातिपदिकस्य विशेषणात् ॥

(उद्द्योतः) विधीयते इति । सूत्रे विधिशब्देन प्रतिषेधविरोधी न विवक्षित इति भावः ॥

(प्रयोजने भाष्यवार्तिकम्)

॥ अपरिमाणबिस्तादिग्रहणं च प्रतिषेधे प्रयोजनम् ॥

(भाष्यम्)

"अपरिमाणबिस्ताचितकम्बल्येभ्यो न तद्धितलुकि" द्विबिस्ता, द्विपरमबिस्ता । त्रिबिस्ता, त्रिपरमबिस्ता ॥

(प्रदीपः) द्विपरमदिस्त्रेति । द्विगुना सन्निधापित-मुत्तरपदं दित्यादिभिर्विशेष्यत इति तदन्तविधिः ॥

(४१३ प्रयोजनवार्तिकम् ॥ १ ॥)

॥ * ॥ दिति ॥ * ॥

(भाष्यम्)

दितिग्रहणं च प्रयोजनम् ॥ दितेरपत्यं दैत्यः, अदितेरपत्यमादित्यः - इति । अदितिग्रहणं न कर्तव्यं भवति ॥

(प्रदीपः) दितिग्रहणं चेति । परमदित्यादिभ्य-स्त्वनभिधानात् ण्यो न भवति ॥

(४१४ प्रयोजनवार्तिकम् ॥ २ ॥)

॥ * ॥ रोण्या अण् ॥ * ॥

(भाष्यम्)

रोण्या अण्ग्रहणं च प्रयोजनम् । आजकरोणः । सैंहिकरोणः ॥

(४१५ आक्षेपवार्तिकम् ॥ ३ ॥)

॥ * ॥ तस्य च ॥ * ॥

(भाष्यम्)

तस्य चेति वक्तव्यम् । रौणः ॥

(प्रदीपः) तस्य चेति । स्वं रूपमित्यस्यानुवृत्तिं वार्तिककारो नेच्छति । तथा चाद्यन्तवदित्यत्र येन विधिस्तदन्तत्व इति प्रयोजनमवोचत् ॥

(उद्द्योतः) ननु स्वंरूपमित्यनुवृत्त्या तस्यापि संज्ञासिद्धौ किं तस्य चेत्यनेन? अत आह—स्वमिति । तेन सूत्रप्रत्याख्याना-दिति तात्पर्यम् ॥

(प्रत्याक्षेपभाष्यम्)

किं पुनः कारणं न सिध्यति । न तदन्ताच्च तदन्तविधिना सिद्धम्, केवलाच्च व्यपदेशिवद्भावेन?

(समाधानभाष्यम्)

"व्यपदेशिवद्भावोऽप्रातिपदिकेन" ॥

(प्रदीपः) व्यपदेशिवद्भावोऽप्रातिपदिकेनेति । ननु रोणीशब्दो न प्रातिपदिकं, प्रत्ययान्तत्वात् ॥ नैष दोषः । 'अप्रातिपदिकेन' इत्यत्र वाक्ये प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणमिति वचनात् स्त्रीप्रत्ययान्तैरपि व्यपदेशिवद्भावो न भवति । न च लिङ्गविशिष्टपरिभाषा स्वरूपविधिविषयैवेति प्रातिपदिकसूत्रे वक्ष्यते ॥

(उद्द्योतः) प्रत्ययान्तत्वादिति । स्त्रीप्रत्ययान्तत्वादित्यर्थः ॥ स्वरूपविधिविषयैवेति । प्रातिपदिकविशेषोपादानविहितकार्यविषयैवेत्यर्थः ॥

(आक्षेपभाष्यम्)

किं पुनः कारणं "व्यपदेशिवद्भावोऽप्रातिपदिकेन" ॥

(उद्द्योतः) किं पुनः कारणमिति । भाष्ये कारणशब्दः प्रयोजनवाची ॥

(समाधानभाष्यम्)

इह सूत्रान्ताट्ठग्भवति दशान्ताड्डो भवतीति केवलादुत्पत्तिर्मा भूदिति ॥

(समाधानबाधकभाष्यम्)

नैतदस्ति प्रयोजनम् ॥ सिद्धमत्र तदन्ताच्च तदन्तविधिना, केवलाच्च व्यपदेशिवद्भावेन । सोऽयमेवं सिद्धे सति यदन्तग्रहणं करोति तज्ज्ञापयत्याचार्यः— सूत्रान्तादेव, दशान्तादेवेति ॥

(उद्द्योतः) तज्ज्ञापयतीति । बोधयतीत्यर्थः । अन्तग्रहणं नियमार्थमिति तात्पर्यम् ॥

(समाधानसाधकभाष्यम्)

नात्र तदन्तादुत्पत्तिः प्राप्नोति । इदानीमेव ह्युक्तम्—*समासप्रत्ययविधौ प्रतिषेधः* इति ॥

(उद्द्योतः) नात्र तदन्तादिति । ननु समासप्रत्ययविधावित्यस्य विशेषणविशेष्यभावव्यत्यासमात्रतात्पर्यग्राहकतया दित्यादाविवात्रापि तदन्तविधिसंभवेनान्तग्रहणसामर्थ्यादेव केवलेऽप्रवृत्तौ 'अप्रातिपदिकेन' इति व्यर्थम् ॥ एतेन ग्रहणवतेति निषेधात्तदन्तविधिर्दुर्लभ इत्यपास्तम् ॥ किंच परमदित्यादिभ्य इवानभिधानेन केवलेऽप्रवृत्तिरिति व्यर्थैव सेति चेन्न । विशेषणविशेष्यभावव्यत्यासतात्पर्यग्राहकतया समासेत्यादिप्रतिषेधवचनवदस्याप्यावश्यकत्वात्सूत्रभाष्यवार्तिकारूढतात्पर्यग्राहकाभावेऽपि तदन्तविधिकल्पनेऽतिप्रसङ्गापत्तेः । अत एवोगिद्वर्णग्रहणवर्जमित्यादेश्चारितार्थ्यम् । अनभिधानेन प्रत्याख्यानं तु न चमत्कारकारि ॥

(गौरवाक्षेपभाष्यम्)

सा तर्ह्येषा परिभाषा कर्तव्या ॥

(उद्द्योतः) सा तर्ह्येषेति । व्यपदेशिवद्भावोऽप्रातिपदिकेनेत्येषा ॥

(गौरवनिराकरणभाष्यम्)

न कर्तव्या । आचार्यप्रवृत्तिर्ज्ञापयति भवत्येषा परिभाषा—'व्यपदेशिवद्भावोऽप्रातिपदिकेन'-इति । यदयम्—"पूर्वादिनिः" "सपूर्वाच्च" इत्याह ॥

(उद्द्योतः) यदयमिति । पूर्वादित्यंशो ज्ञापक इत्यर्थः ॥

(ज्ञापकनिराकरणभाष्यम्)

नैतदस्ति ज्ञापकम् ॥ अस्ति ह्यन्यदेतस्य वचने प्रयोजनम् ॥

किम्?

सपूर्वात् पूर्वादिनिं वक्ष्यामीति ॥

(प्रदीपः) सपूर्वादिति । पूर्वग्रहणे त्यक्ते सपूर्वादिनिरित्युच्यमाने सर्वस्मात् सपूर्वात्प्राप्नोतीति कथं ज्ञापकमित्यर्थः ॥

(उद्द्योतः) सर्वस्मादिति । पूर्वशब्दव्यतिरिक्तादपीत्यर्थः ॥

(ज्ञापकान्तरभाष्यम्)

यत्तर्हि योगविभागं करोति ॥ इतरथा "पूर्वात्स-पूर्वादिनिः" इत्येव ब्रूयात् ॥

(उद्योतः) भाष्ये–यत्तर्हि योगविभागमिति । न चेष्टादिभ्यश्चेत्यत्रानुवृत्त्यर्थं तथा पाठः, अत एवानिष्टीति प्रयोगसिद्धिरिति वाच्यम् । एतद्भाष्यप्रामाण्येन तत्प्रयोगाभावानुमानात् । प्रकारान्तरेण सिद्धौ तु नास्माकं क्षतिः । एकयोगेऽपि तावति स्वरितत्वप्रतिज्ञासामर्थ्येन तावत उत्तरत्रानुवृत्तिसिद्धेश्चेति दिक् ॥ एवं च रोणीत्यादौ केवलस्याप्राप्तेस्तस्य चेति वक्तव्यमिति सिद्धम् ॥

(आक्षेपभाष्यम्)

किं पुनरयमस्यैव शेषः—*तस्य च* इति ?

(समाधानभाष्यम्)

नेत्याह । यच्चानुक्रान्तं, यच्चानुक्रंस्यते, तस्य सर्वस्यैव शेषः—*तस्य च* इति ॥

(प्रदीपः) यच्चानुक्रान्तमिति । अप्रातिपदिकेनेति तु निषेधो यत्रान्तग्रहणं सूत्र एवोपात्तं तत्र । यथा—दशान्ताड्ड इति 'दश अधिका अस्मिन् शते' इत्यत्र न भवति ॥

(उद्योतः) ननु तदन्तविधिविषये तस्य चेत्यनेन केवलादपि चेत्, व्यपदेशिवद्भावोऽप्रातिपदिकेनेति व्यर्थमत आह—अप्रातिपदिकेनेति । ज्ञापकस्य सजातीयापेक्षत्वादिति भावः ॥ अत एव पूर्वादिनिरित्येव तदन्तविधिना सिद्धे सपूर्वाच्चेत्यस्य ग्रहणवतेति परिभाषाज्ञापकत्वं कैयटोक्तं सङ्गच्छते ॥ यत्रान्तेत्यन्तग्रहणमुपलक्षणम् । अत एव एकगोपूर्वादित्यस्य केवलैकशब्दे न प्रवृत्तिः । ग्रहणवतेत्यपि प्रत्ययविधौ निषेधस्यैवानुवादकं, लाघवात् । स्पष्टं चेदं असमासे निष्कादिभ्य इति सूत्रे भाष्यकैयटयोः ॥

(प्रयोजने भाष्यवार्तिकम्)

॥ रथसीताहलेभ्यो यद्विधौ प्रयोजनम् ॥

(भाष्यम्)

रथ्यः, परमरथ्यः । सीत्यं, परमसीत्यम् । हल्या, परमहल्या ॥

(प्रदीपः) यद्विधाविति । ठग्विधौ तु तदन्तविधेरभावात् 'पारमहलिकः' इति ठक् न भवति ॥

(उद्योतः) रथ्ये-'तद्वहति रथ-' इति यत् । सीत्ये—नौवयोधर्मेति । हल्ये—मतजनहलात्करणजल्पकर्षेष्विति यत् ॥ भाष्ये—परमरथ्य इति । रथाद्यथाङ्गयोर्द्वोरित्येवं शैषिकप्रकरणे पाठेन सिद्धे तद्वहतीत्यत्र रथग्रहणं रथांशे तदन्तविधौ ज्ञापकम् । शैषिके यति हि द्विरथ इत्यादौ द्विगोर्लुगिति लुक् । तत्र सूत्रेऽचीति न संबध्यते । अनभिधानाच्च नातिप्रसङ्गः । वहत्यर्थे तु द्विरथ्य इत्येव, तस्याप्राग्दीव्यतीयत्वात् । इतरयोस्तु वाचनिक एव ॥ यत्तु हलसीराट् ठगित्यपि 'तस्येदं' 'तद्वहति-' इत्यधिकारे च द्विः पठ्यते, तत्तु इदंशब्देन वोढृरूपार्थग्रहणज्ञापकम् । तदाह—ठक् न भवतीति ॥

(प्रयोजने भाष्यवार्तिकम्)

॥ सुसर्वार्धदिक्छब्देभ्यो जनपदस्य प्रयोजनम् ॥

(भाष्यम्)

सुपाञ्चालकः, सुमागधकः । सु ॥
सर्वपाञ्चालकः, सर्वमागधकः । सर्व ॥
अर्धपाञ्चालकः, अर्धमागधकः । अर्ध ॥
दिक्छब्द—पूर्वपाञ्चालकः, पूर्वमागधकः ॥

(उद्योतः) भाष्ये–सुपाञ्चालक इत्यादि । जनपदेत्यधिकारे अवृद्धादपि बहुवचनविषयादिति वुञ् । तद्विधौ चायं तदन्तविधिः । सुसर्वार्धाज्जनपदस्य-दिशोऽमद्राणामिति उत्तरपदवृद्धिः ॥

(प्रयोजने भाष्यवार्तिकम्)

॥ ऋतोर्वृद्धिमद्विधाववयवानां प्रयोजनम् ॥

(भाष्यम्)

पूर्वशारदम् । अपरशारदम् । पूर्वनैदाघम् । अपरनैदाघम् ॥

(प्रदीपः) ऋतोरिति । ऋतुवाचिनः शब्दाद्यो वृद्धिमान् प्रत्ययस्तद्विधानेऽवयवानां तदन्तविधिः । शरदः पूर्वो भागः—पूर्वशरत्, तत्र भवमिति ऋतुलक्षणोऽण् । तत्र वृद्धिमदिति वचनात् प्रावृष एण्य इत्यत्र तदन्तविधिर्न भवति । तेन ऋत्वणेव भवति—पूर्वप्रावृषमिति । प्रावृट्शब्दो वर्षापर्यायः ॥ अवयवानामिति किम् ? पूर्वस्यां शरदि–पौर्वशरदिकमित्यण् न भवति, कालाट्ठञित्येव भवति । तत्र हि यथाकथञ्चित्कालवाचिनो गृह्यन्ते ॥

(उद्योतः) वृद्धिमानिति । वृद्धिनिमित्तमित्यर्थः ॥ अवयवानामिति । पूर्वपदस्थे इति शेषः ॥ शरद इति । पूर्वापराधरेत्येकदेशिसमासः । सन्धिवेलाद्यृत्विति अण् । अवयवादृतोरित्युत्तरपदवृद्धिः ॥ ननु शरच्छब्द एव कालवाची न पूर्वशरच्छब्द इति कथं ठञित्यत आह—तत्र हीति । अत एव सन्धिवेलादिसूत्रे नक्षत्राणां कालेन विशेषणं सङ्गच्छते ॥

(प्रयोजने भाष्यवार्तिकम्)

॥ ठञ्विधौ संख्यायाः प्रयोजनम् ॥

(भाष्यम्)

द्विषाष्टिकं, पञ्चषाष्टिकम् ॥

(प्रदीपः) द्विषाष्टिकमिति । द्वे षष्टी परिमाणमस्येति समासे कृते आर्हादिति ठक् न भवति, संख्यायास्तदन्तविधौ सति संख्यान्तादपि ठक्प्रतिषेधात् । तेन प्राग्वतेरिति ठञ् भवति । अध्यर्धपूर्वेति लुग्न भवति, सोऽस्यांशवस्नभृतय इत्यतः 'सोऽस्य' इत्यनुवर्तमाने तदस्य परिमाणमित्यत्र पुनः प्रत्ययार्थसमर्थविभक्तिनिर्देशात् । कृते वा लुकि पुनस्तन्निर्देशसामर्थ्यात् पुनः प्रत्ययः । तद्विधानसामर्थ्याच्च पुनर्लुगभावः ॥

(उद्योतः) भाष्ये—ठञ्विधौ सङ्ख्याया इति । तदस्य परिमाणं-सङ्ख्यायाः संज्ञेति सूत्रे इति भावः ॥ द्वे षष्टीपरिमाणमस्येति । सङ्ख्यादिरस्य विशेष्यः ॥ प्रतिषेधादिति । आर्हादगोपुच्छेत्यनेन । तस्य प्रत्ययप्रतिषेधत्वात्तत्र तदन्तविधिर्भवत्येव ॥ तेन प्राग्वतेरिति । ठञ्विधायके सङ्ख्यायाः संज्ञेति सूत्रे तदन्तविधिसत्त्वेन प्राग्वतेरित्यधिकारप्राप्तठञ् भवतीत्यर्थः ॥ पुनः प्रत्ययार्थसमर्थेति । अस्येति प्रत्ययार्थः, तदिति समर्थविभक्तिः, अनुवर्तमानस्य लुक्संबद्धतया पुनरुपादानेन तद्विलक्षणत्वसूचनादनेन विहितस्य लुगभाव इत्यर्थः ॥ कृते चेति । अनुवर्तमानसोऽस्येतिसहितपरिमाणमित्यनेन विहितस्य लुकि पुनस्तदस्य परिमाणमितिवचनसामर्थ्यात्स्वार्थे तज्जातीयप्रत्यये तस्य विधानसामर्थ्याद् द्विगुनिमित्तत्वाभावाद्वा लुगभाव इत्यर्थः ॥ इदं वृत्तिकारमतेनोक्तम् । वस्तुतस्तु तदस्येति पुनरुपादानमात्रेणार्हीयत्वापगमे तस्त्वेऽपि लुगभावे वा द्वे षष्टी जीवितपरिमाणमस्येत्यर्थेऽनेन ठञि लुकमाशङ्क्य कालादित्यधिकारस्थेन तमधीष्ट इति सूत्रेण ठञा द्विषाष्टिकः साधितो भाष्ये। कालग्रहणेन यथाकथंचित् कालवाचिनो ग्रहणमिति चोक्तं, तद्विरुध्येत। स्वद्रीत्याऽनेनापि ठञि लुगभावात् । तस्माद्वे षष्टी परिमाणमस्य सङ्घस्य स परिमाणमस्येति भाष्योदाहरणार्थः । तत्र द्विगुनिमित्तत्वाभावान्न लुक् । सङ्घे द्विषष्ट्यनतिरेकस्यापि सत्त्वात्तस्यापि सङ्ख्याशब्दत्वमित्यपरे ॥

(प्रयोजने भाष्यवार्तिकम्)

॥ धर्मादनञः प्रयोजनम् ॥

(भाष्यम्)

धर्मं चरति—धार्मिकः । अधर्मं चरति-अधार्मिकः ॥ *अधर्माच्च*इति न वक्तव्यं भवति ॥

(पदाङ्गाधिकारपरिभाषासाधनम्)

(४१६ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ पदाङ्गाधिकारे तस्य च तदुत्तरपदस्य च ॥ * ॥

(भाष्यम्)

पदाङ्गाधिकारे तस्य च तदुत्तरपदस्य चेति वक्तव्यम् ॥

(प्रदीपः) पदाङ्गाधिकार इति । पदशब्देनोत्तरपदं गृह्यते, पदैकदेशलोपात् ॥

(उद्योतः) भाष्ये—पदाङ्गेति । तदन्तविधेरपवादोऽयम् । अत एव तस्य चेति पुनरभिहितम् । तदन्तविधौ हि बहुच्पूर्वेऽपि स्यात्तच्च नेष्टमिति वार्तिकाशयः ॥ पदशब्देनेति । अत एव भाष्ये उत्तरपदाधिकारे प्रयोजनदानम् ॥

(भाष्यम्)

पदाधिकारे किं प्रयोजनम् ?

(प्रयोजने भाष्यवार्तिकम्)

॥ * ॥ प्रयोजनमिष्टकेषीकामालानां चिततूलभारिषु ॥ * ॥

(भाष्यम्)

इष्टकचितं चिन्वीत । पक्वेष्टकचितं चिन्वीत । इषीकतूलेन, मुञ्जेषीकतूलेन । मालभारिणी कन्या, उत्पलमालभारिणी कन्या ॥

(प्रदीपः) उत्तरपदेन सामर्थ्यादाक्षिप्तं पूर्वपदमिष्टकादिभिर्विशेष्यते ॥

(उद्योतः) तदन्तविध्यपवादत्वादस्यापि विशेषण एव प्रवृत्तिरित्याशयेनाह—उत्तरपदेनेति । शब्दरूपं विशेष्यमादायेत्यन्ये ॥

(भाष्यम्)

अङ्गाधिकारे किं प्रयोजनम् ?

(प्रयोजने भाष्यवार्तिकम्)

॥ * ॥ प्रयोजनं महदप्स्वसृनप्तॄणां दीर्घविधौ ॥ * ॥

(भाष्यम्)

महान्, परममहान् । महत् ॥

अप्—आपस्तिष्ठन्ति, स्वापस्तिष्ठन्ति । अप् ॥

स्वसृ—स्वसारौ, स्वसारः । एवं परमस्वसा, परमस्वसारौ, परमस्वसारः ॥

नप्तृ—नप्ता, नप्तारौ, नप्तारः । एवं परमनप्ता, परमनप्तारौ, परमनप्तारः ॥

(प्रदीपः) महदिति । महदादिभिरङ्गं विशेष्यते ॥ स्वाप इति । न पूजनादिति समासान्तनिषेधः । अपो भीति तत्वमपि स्वद्भिरिति भवति ॥

(उद्योतः) समासान्तनिषेध इति । ऋक्पूरब्धिति प्राप्ते ॥ अत एव द्व्यन्तरुपसर्गेतीत्त्वं न । तत्र स्वाप इति कृतसमासान्तानुकरणम् , व्यत्ययेन षष्ठ्यर्थे प्रथमा । अत्र चेदमेव भाष्यं मानमित्याहुः ॥ तत्त्वमपीति । वार्तिकस्थेन दीर्घविधाविति विषयनिर्देशेनेदं विरुध्यते ॥

(४१७ प्रयोजनवार्तिकम् ॥ २ ॥)

॥*॥ पद्युष्मदस्मदस्थ्याद्यनडुहो नुम् ॥*॥

(उद्योतः) भाष्ये—पद्युष्मदस्मदस्थ्यादि इति समस्तं पृथक्पदम् । अनडुह इति स्वसमस्तम् । अन्यथा नुमोऽनडुच्छब्दमात्रान्वयित्वेनासामर्थ्यात्समासो न स्यात् । पदादयोऽनडुहो नुम् च तदन्तविधिं प्रयोजयन्तीत्यर्थः ॥

(व्याख्याभाष्यम्)

पद्भावः प्रयोजनम् । द्विपदः पश्य ॥

(प्रदीपः) द्विपद इति । पादः पदित्यत्र पाच्छब्देनाङ्गं विशेष्यते ॥

(आक्षेपभाष्यम्)

अस्ति चेदानीं कश्चित्केवलः पाच्छब्दो यदर्थो विधिः स्यात् ?

(उद्योतः) समासे एव पादस्य लोप इत्यन्तलोपविधानात्सामर्थ्यादेव तदन्तविधिर्भविष्यतीत्याशयेन काका पृच्छति — भाष्ये— अस्ति चेति ॥

(समाधानभाष्यम्)

नास्तीत्याह ॥

(प्रयोजनदर्शकभाष्यम्)

एवं तर्हि अङ्गाधिकारे प्रयोजनं नास्तीति कृत्वा पदाधिकारस्येदं प्रयोजनमुक्तम्—"हिमकाषिहतिषु च"। यथा—पत्काषिणौ, पत्काषिणः। एवं परमपत्काषिणौ, परमपत्काषिणः ॥

(उद्योतः) आचार्यदेशीय आह—एवं तर्हीति। संनिधेर्लिङ्गं बलीय इति भावः ॥

(आक्षेपभाष्यम्)

यदि तर्हि पदाधिकारे पादस्य तदन्तविधिर्भवति। "पादस्य पदाज्यातिगोपहतेषु"। यथेह भवति—पादेनोपहतं—पदोपहतम्। एवमत्रापि स्यात्—द्विग्धपादेनोपहतं-द्विग्धपादोपहतमिति ॥

(प्रदीपः) पादस्य पदेति। ननु पद्भावे तदन्तविधिरुक्तः। अयं तु पदभावविधिः। नैष दोषः। पादशब्देन पूर्वपदस्य विशेषणात्पद्भावे तदन्तविधिः। अनेनैव न्यायेन पदभावेऽपि तदन्तविधिप्रसङ्गः, यथाभूतः पूर्वसूत्रे पादशब्दो निर्दिश्यते तथाभूतस्योत्तरसूत्रेऽनुवर्तनात्।"

(उद्योतः) तदन्तविधिरिति। तदपवाद उत्तरपदविधिरित्यर्थः ॥ अर्थाधिकाराश्रयेण परिहरति—नैषेति ॥

(समाधानभाष्यम्)

एवं तर्ह्यङ्गाधिकार एव प्रयोजनम् ॥

(प्रदीपः) एवं तर्हीति। एवं च परमपादेन कषतीति विवक्षायां परमपादकाषीति भवति। यदा तु परमः पत्काषीति विवक्षा तदा परमपत्काषीति भवति ॥

(उद्योतः) नन्वेवं पादशब्देन तदन्तविध्यभावे परमपत्काषिणाविति पूर्वोदाहृतासङ्गतिरत आह—एवं चेति। अर्थभेदेन तत्साधिरिति भावः ॥

(आक्षेपभाष्यम्)

ननु चोक्तम्—नास्ति केवलः पाच्छब्द इति ॥

(समाधानभाष्यम्)

अयमस्ति—पादयतेरप्रत्ययः-पात्, पदौ, पदः। पत् ॥

(प्रदीपः) पादयतेरिति। पदेर्ण्यन्तादित्यर्थः ॥

(उद्योतः) पादशब्दादाख्यानणिचि णिनिमित्तकटिलोपस्य स्थानिवत्त्वात्पदादेशाप्राप्तेराह—पदेरिति। णौ लुप्तमिति निषेधाच्च णिलोपस्य स्थानिवत्त्वमित्यर्थः ॥ अत एव पादस्य पादहस्त्यादिभ्य इति नासत्रि। तथा सति तस्यैव प्रतिपदोक्तत्वात्पद्भावः स्यान्नास्येति तात्पर्यम् ॥

(व्याख्याभाष्यम्)

युष्मद् अस्मत्—यूयं, वयम्। अतियूयं, अतिवयम् ॥

अस्थ्यादि—अस्थ्ना, दध्ना, सक्थ्ना। परमास्थ्ना, परमदध्ना, परमसक्थ्ना ॥

अनडुहो नुम्—अनड्वान्, परमानड्वान् ॥

(प्रयोजने भाष्यवार्तिकम्)

॥ द्युपथिमथिपुंगोसखिचतुरनडुत्त्रिग्रहणं प्रयोजनम् ॥

(भाष्यम्)

द्यौः, सुद्यौः। पन्थाः, सुपन्थाः। मन्थाः, परममन्थाः। पुमान्, परमपुमान्। गौः, सुगौः। सखा, सखायौ, सखायः, परमसखा, परमसखायौ, परमसखायः। चत्वारः, परमचत्वारः। अनड्वाहः, परमानड्वाहः। त्रयाणां, परमत्रयाणाम् ॥

(प्रदीपः) 'परमपन्थाः' इति क्वचित्पाठः स त्वयुक्तः, समासान्तविधानात् ॥ न पूजनादित्यत्र पूजायां स्वतिग्रहणमिति वचनान्नास्ति निषेधः। तस्मात्सुपन्था इति पाठः ॥ परमगौरित्ययमप्यपपाठः, गोरतद्धितलुकीति टज्विधानात्। तस्मात् सुगौरिति पाठः। परमसखायाविति बहुव्रीहिः। तत्पुरुषे तु टचा भाव्यम् ॥ अनडुच्छब्दस्येह प्रपञ्चार्थः पाठः। अनडुहो नुम् इत्यत एव वचनादादित्यधिकारादमामोः कृतयोर्नुम्विधानात् नुम्विधौ तदन्तविधिना अमामोरपि तदन्तविधेराक्षेपात् ॥ अन्ये त्वाहुः—असतीह पुनर्ग्रहणे यत्रैव नुम् क्रियते तत्रैवामामौ तदन्तस्य स्याताम्। परमानड्वाह इत्यत्र त्वाम् न स्यादिति पुनः पाठः कर्तव्यः। पूर्वत्रापि पाठो नुमर्थः कर्तव्यः। अन्यथा—अमामोरेव तदन्तविधिः स्यात्, न नुम्विधौ ॥

(उद्योतः) इह-द्युपथीति प्रयोजनवार्तिके ॥ इत्यत एवेति। पद्युष्मदिति वार्तिकस्यादित्यर्थः ॥ आदित्यधिकारादिति। आच्छीत्यतः। अन्यथा नुम् बाधकः स्यात्, अम् च नुमो बाधकः स्यादिति भावः ॥ अन्यथाऽमामोरेवेति। चतुःसाहचर्यादिति भावः ॥

(प्रयोजनभाष्यवार्तिकम्)

॥ त्यदादिविधिभस्त्रादिस्त्रीग्रहणं च प्रयोजनम् ॥

(भाष्यम्)

सः, अतिसः। भस्त्रका, भस्त्रिका, निर्भस्त्रका, निर्भस्त्रिका, बहुभस्त्रका, बहुभस्त्रिका ॥

स्त्रीग्रहणं च प्रयोजनम्। स्त्रियौ, स्त्रियः। राजस्त्रियौ, राजस्त्रियः ॥

(प्रदीपः) अतिस इति। शोभनः स इत्यर्थः। उपसर्जने तु तच्छब्दार्थेऽतितदिति भवति ॥ बहुभस्त्रिकेति। तन्पूर्वाणामपीति न वक्तव्यं भवति ॥

(४१८ प्रयोजनवार्तिकम् ॥ २ ॥)

॥ * ॥ वर्णग्रहणं च सर्वत्र ॥ * ॥

(भाष्यम्)

वर्णग्रहणं च सर्वत्र प्रयोजनम् ॥

क सर्वत्र ?

अङ्गाधिकारे चान्यत्र च । अन्यत्रोदाहृतम् ॥ अङ्गाधिकारे—"अतो दीर्घो यञि, सुपि च" इहैव स्यात्—आभ्याम् । रदाभ्यामित्यत्र न स्यात् ॥

(प्रदीपः) वर्णग्रहणं चेति । यचेवमुगिद्वर्णग्रहणवर्जमित्यत्र किमर्थं वर्णग्रहणम् ? उच्यते—प्रत्ययविधौ तदन्तविधिप्रतिषेधाद्वर्णग्रहणे प्रत्ययविधौ प्रतिषेधाशङ्कानिवारणार्थम् ॥

(उद्योतः) अन्यत्र चेति भाष्यादङ्गाधिकारादन्यत्र प्रत्ययविधानेऽपि वर्णग्रहणे तदन्तविधिरिति मत्वा नोदयति—यचेवमिति । अन्यत्रेत्यनेन भाष्येणेकोझलीत्यादौ निषेधाभावात्तदन्तविधिरनुज्ञायते । एवं च प्रत्ययविधौ वर्णग्रहणे स प्रतिषेध एव स्यादतस्तत्र वर्णग्रहणमिति परिहरति—उच्यत इति ॥

(४१९ प्रयोजनवार्तिकम् ॥ ३ ॥)

॥ * ॥ प्रत्ययग्रहणं चापञ्चम्याः ॥ * ॥

(भाष्यम्)

प्रत्ययग्रहणं च अपञ्चम्याः प्रयोजनम् ॥ यञिञोः फग्भवति—गार्ग्यायणः, वात्स्यायनः, परमगार्ग्यायणः, परमवात्स्यायनः ॥

अपञ्चम्या इति किमर्थम् ?

दृषत्तीर्णा, परिषत्तीर्णा ॥

(प्रदीपः) प्रत्ययग्रहणं चापञ्चम्या इति । प्रत्ययग्रहणे यस्मात् स विहित इति सिद्धे तदन्तविधावपञ्चम्या इति प्रतिषेधार्थं वचनम् ॥ यत्र पञ्चम्यन्तात् परः प्रत्ययः कार्यान्तरविधानाय परिगृह्यते तत्र तदन्तविधिर्मा भूत् । यथा—रदाभ्यामित्यत्र । तत्र हि तदन्तविधौ रेफदकाराभ्यामुत्तरो यो निष्ठान्तस्तस्य यस्तकारस्तस्य नत्वं स्यात् । न च संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिर्नास्तीति निषेधावतारः । यत्र हि संज्ञाविधानं तत्रायं निषेधः । इह तु निष्ठानुवादेन नत्वविधिः । संज्ञाविधौ तर्हि तदन्तविधिनिषेधस्य किं फलम् ? उच्यते—यदि संज्ञाविधौ प्रत्ययग्रहणे तदन्तस्य संज्ञा स्यात् प्रदेशेषु पुनस्तदन्तविधिः स्यादिति प्रत्ययान्तान्तं गृह्येत तस्मात्संज्ञाविधावपि तदन्तविधेर्निषेधो रदाभ्यामित्यत्र च ॥ अपञ्चम्या इत्यस्य नायमर्थः—यत्र पञ्चम्यन्तात्प्रत्ययो विधीयते तत्र तदन्तविधिर्न भवतीति । एवं हि व्याख्यायमाने ञितश्च तत्प्रत्ययादित्यत्र तत्प्रत्ययादेवाञि विधीयमाने तस्यैवाङ्गसंज्ञायां वृद्धिस्वरौ स्यातां, न तु तदन्तस्य ॥ परमगार्ग्यायण इति । गार्ग्यायण इत्येवोदाहरणम् । गार्ग्यशब्दाद्यञन्तात् फग्विधानात् । न त्वत्र परमगार्ग्यशब्दात्प्रत्ययः, तस्य यञन्तत्वाभावात् । तस्माच्च फकि विधीयमाने पारमगार्ग्यायण इत्यनिष्टरूपप्रसङ्गः । तस्मादेतन्न्यायव्युत्पादनार्थं परमगार्ग्यायण इत्युपन्यस्तम् । उत्तरपदाधिकारे प्रत्ययग्रहणेन तदन्तविध्यभावो लेखग्रहणेन ज्ञापितः । तत्र रदाभ्यामित्यत्र निष्ठायाः प्राधान्येनाश्रयणात्तदन्तविध्यभावः । स्यतासी लृलुटोरित्यत्र धातोरित्यधिकारादपञ्चम्या इति निषेधात्, लृलुटोर्वा प्राधान्येनाश्रयणात्तदन्तविध्यभावः ॥

(उद्योतः) सिद्धे तदन्तविधाविति । उक्तवचनेन वाचनिक इत्यर्थः । यत्तु प्रत्ययाक्षिप्तप्रकृतिप्रत्ययावयवकसमुदायस्य विशेषणादेतत्सूत्रसिद्ध एव स इति ॥ तन्न । तादृशार्थस्य नियताक्षेपे आक्षिप्तस्य वा शाब्देऽन्वये मानाभावात् । किं च वनो रचेत्यादौ समासप्रत्ययविधावित्यनेनास्यापि निषेधापत्तिः, मम तु सौत्रस्यैव स निषेध इति न दोषः ॥ पञ्चम्यन्तात्परः प्रत्ययो यत्र कार्यान्तरविधानायानूद्यते तद्भिन्नस्थले प्रत्ययग्रहणं तदन्तविधेः प्रयोजनमिति वार्तिकार्थस्तदाह—यत्रेत्यादि । परिगृह्यते—अनूद्यते ॥ नत्वं स्यादिति । दृषत्तीर्णेत्यादौ धातोस्तकारस्य तत्पूर्वदस्य च तत्स्यादित्यर्थः ॥ न च संज्ञाविधाविति । संज्ञाया विधावित्यर्थं इत्यभिमानः ॥ यत्र हीति । संज्ञाया विधौ स निषेधो न तु संज्ञया विधौ ॥ तर्हीति । प्रदेशेषु तदन्तग्रहणं यदि, तर्हि · इत्यर्थः ॥ पुनस्तदन्तेति । घादिभिरुत्तरपदस्य विशेषणादिति भावः ॥ तस्मादिति । संज्ञाविधौ प्रत्ययग्रहण इति प्रत्ययग्रहणे चापञ्चम्या इति वचनाभ्यामिति भावः ॥ नायमर्थ इति । प्रत्यासत्त्या चास्यार्थस्य प्रसक्तिः ॥ पञ्चम्यन्तादिति । पञ्चम्यन्तनिर्दिष्टप्रत्ययादित्यर्थः ॥ समासप्रत्ययविधाविति तु सौत्रस्य निषेध इति न तेनास्य गतार्थतेति भावः ॥ तत्प्रत्ययादेव–विकारावयवविहितप्रत्ययादेव ॥ एवञ्चोष्ट्रविकाराद्–औष्ट्रकादञि वुञ एव वृद्धिस्वरौ स्यातामित्यर्थः ॥

भाष्ये—यञिञोः फगिति । यद्यपि ङ्याप्प्रातिपदिकादित्यधिकारादपञ्चम्या इति निषेधस्तत्र प्राप्नोति तथापि न तत् व्यधिकरणं विशेषणम्, किंतु यञिञोरिति पञ्चम्यर्थे षष्ठीसत्त्वात् तस्य समानाधिकरणं विशेष्यमिति अपञ्चम्या इत्यस्याविषयोऽयमिति भावः ॥

तस्मादिति । प्रत्ययग्रहणे यस्मात्स विहित इति नियमोऽत्रापि तदन्तविधावपेक्ष्य एव । एतत्सिद्ध एव च तदन्तविधिस्तत्रानूद्यते उक्तनियमबोधनाय । अन्यथा परमगार्ग्यशब्दात् फकि पारमगार्ग्यायण इति स्यादिति न्यायव्युत्पादनार्थमित्यर्थः ॥ नन्वेतद्रीत्या परमश्चासौ गार्ग्यायण इति भाष्योदाहरणार्थः, न हीदृशेऽर्थे परमगार्ग्यशब्दस्य प्रकृतित्वसंभावनाऽपीति कथमेतन्न्यायप्रदर्शनमनेन भाष्येणेति चेन्न । परमगार्ग्यैकदेशगार्ग्यशब्दादेव प्रत्ययः परमगार्ग्यस्यापत्यमित्यर्थेऽपि उक्तन्यायात्-इत्यदोषात् । विशिष्टेनैकार्थीभावेऽवयवेनापि तस्य सत्त्वमस्त्येव ॥ निष्कृष्यैकार्थीभाव एव वृत्तौ निमित्तमित्यत्र न मानम् । अत एवानुपसर्जनादिति सूत्रे कुम्भकारीशब्दैकदेशात्कारीशब्दादव्युत्पत्तिः शङ्किता भाष्ये ॥ अस्य कैयटस्याप्यत्रैव तात्पर्यम् ॥ एतन्न्यायेत्यस्यापि यस्माद्विहित इत्यादिन्यायेन समस्तैकदेशात्प्रत्यय इत्येतन्न्यायेत्यर्थः । न चैवं सुपि च-रोः सुपीत्यादौ सुबन्ते इत्यर्थापत्तिः, न हि तत्र पञ्चम्यन्तात्परत्वेन प्रत्ययो विशेष्यत इति वाच्यम् । तस्मिन्निति परिभाषया सुपि परे इत्यर्थे नियमेन कस्मादित्यवधिसाकाङ्क्षत्वेनोपस्थिताङ्गादेरेवावधित्वेनान्वयेन पञ्चम्यन्तस्य विशेषणत्वेन निषेधप्रवृत्तेरित्याहुः ॥ ननु येन नाप्राप्तिन्यायेनायं निषेधो वाचनिकतदन्तविधेरेवेति घरूपेत्यादौ उत्तरपदस्य विशेष्यतया प्राप्ततदन्तविधिः स्यादेवेत्यत आह—उत्तरपदेति । अन्यथा हृदयस्य हृल्लेखयदण्लासेष्वित्यत्राण्ग्रहणेनैव सिद्धे लेखग्रहणं व्यर्थं स्यात् ॥ लेख इत्यणन्तमेव तत्र गृह्यते । घञन्तस्य त्वनभिधानात्तद्ग्रहणमेवेति भावः ॥

अयमपि निषेधो विशेषणविशेष्यभावव्यत्यासासूचक एवेत्याह—तत्रेति ॥ प्राधान्येनेति । शब्दरूपापेक्षयेत्यर्थः ॥ धातोरिति । इदं सर्वास्वि विशेषणमिति चिन्त्यमिदम् । सुपि चेत्यादावसदुक्तरीत्यैवात्रापि समाधानं बोध्यम् ॥

(४२० आक्षेपवार्तिकम् ॥ ४ ॥)

॥ * ॥ अलैवानर्थकेन ॥ * ॥

(भाष्यम्)

नान्येनानर्थकेनेति वक्तव्यम् ॥

किं प्रयोजनम् ?

हन्ग्रहणे प्लीहन्ग्रहणं मा भूत् । उद्ग्रहणे गर्मुद्ग्रहणम् । स्त्रीग्रहणे शस्त्रीग्रहणम् । संग्रहणे पायसंग्रहणम् ॥

(प्रदीपः) **अलैवानर्थकेनेति** । **अर्थवद्ग्रहणे नानर्थकस्येति** वर्णनिर्देशेषु नाश्रीयत इति स्थितम् । वर्णरूपतया यस्य शब्दस्याश्रयणं नार्थवत्तारूपमाश्रीयते तत्र **वर्णग्रहणं च सर्वत्रे**त्यत्र वर्णग्रहणे जातिग्रहणाद्वर्णसमुदायग्रहणेऽनर्थकस्य ग्रहणं प्राप्तमनेन नियमेन निवार्यते । अलैवेति चैकत्वसंख्या गुणत्वाद्विवक्ष्यते । नियमविधानसामर्थ्याद्वा ॥

हन्ग्रहण इति । तेन प्लीहानाविति दीर्घो भवति ॥ **उद्ग्रहण इति । उदः स्थास्तम्भोरि**त्यनेन गर्मुत्-स्थास्यतीति पूर्वसवर्णाभावः ॥ **शस्त्रीग्रहणमिति** । तेन शस्त्र्याविति स्त्रिया इतीयङ् न भवति ॥ **पायसंग्रहणमिति** । पायसं करोतीति-**संपर्युपेभ्य** इति सुट् न भवति ॥

तत्र हन्ग्रहणे स्त्रीग्रहणे चाङ्गस्य विशेष्यत्वात् स्यात्तदन्तविधिः । उदः स्थेत्यत्र तोरित्यधिकारात् तवर्गान्तस्योच्छब्देन विशेषणात् स्यात्तदन्तविधिः । प्रतिषेधविज्ञाने तु न भवति, उदश्च तवर्गेण विशेष्यत्वात् तोरित्यस्य वा निवृत्तत्वात् । संग्रहणे पदप्रकरणात्तदन्तविधिः स्यादिति निवार्यते । पदेन समादयो विशेष्यन्ते इति तदन्तविध्यभावः । पायसं करोतीति करोतेर्भूषणार्थवृत्तिता संभवतीति सुट् स्यात् ॥

(उद्योतः) नन्वलाऽनर्थकेनेत्ययुक्तं, अर्थवत्परिभाषाविरोधादत आह—अर्थवदिति ॥ स्थितमिति । स्वं रूपमित्यत्रेति शेषः ॥ कुतो हेतोरित्यत आह—वर्णरूपतया तस्येति । वर्णरूपतया यस्येति पाठे नार्थवत्तारूपमित्यतः प्राक् तस्य हीति शेषो बोध्यः ॥ अर्थवत्तेति । तत्समानाधिकरणं रूपमित्यर्थः ॥ वर्णसमुदायग्रहणं प्राप्तमिति पाठेऽनर्थकेत्यादिः । तदपि प्राप्तमिति शेषः ॥ गुणत्वादिति । तदन्तविधिनियमशेषत्वादित्यर्थः ॥ वर्णसमुदायेन चेत्तदन्तविधिस्तर्हि अर्थवतैवेति फलितम् ॥

अन्ये तु—अङ्गाधिकारे तदन्तविधेरतिप्रसङ्गस्य निवारणायेदम् । वर्णग्रहणं चेत्यन्वाख्यानवार्तिके ज्ञापकसिद्धजातिग्रहणे न मानम् । एवमलैवेत्यत्रापि । एकत्वसङ्ख्या गुणत्वादित्यपि चिन्त्यम्, जातिपरत्वे सङ्गतसङ्ख्याया एव तदुत्तरविभक्तिवाच्यत्वेन तद्विवक्षयाऽपि दोषानुद्धारादित्याहुः ॥

दीर्घो भवतीति । हन्ग्रहणमिति नियमेनानिवर्तितत्वादिति भावः । अर्थवत्परिभाषासिद्धार्थानुवादोऽयम् ॥ संपर्युपेभ्य इति । वृत्तिपाठमनुसृत्येदम् ॥ तस्योच्छब्देनेति । वा पदान्तस्येत्यतः पदग्रहणमनुवर्त्य तस्योता विशेषणात्-उदन्तस्य पदस्येत्यर्थ उचितः ॥ नन्वव्यभिचारात्तवर्गेणोदो विशेषणं व्यर्थमत आह—वा निवृत्तत्वादिति । पदग्रहणमपि फलाभावान्निवृत्तम्, विशेषणं चेत्यपि बोध्यम् ॥ पदप्रकरणात्—एङः पदान्तादतीत्यतः ॥ नन्वत्र करोतेर्न भूषणार्थोऽत आह—भूषणेति । पायसं भूषयतीत्यर्थसंभवादिति भावः ॥

(वार्तिकवैयर्थ्याक्षेपभाष्यम्)

किमर्थमिदमुच्यते, न 'पदाङ्गाधिकारे तस्य तदुत्तरपदस्य च' इत्येव सिद्धम् ॥ न चेदं तत्, नापि तदुत्तरपदम् ॥

(प्रदीपः) **किमर्थमिति** । **अलैवानर्थकेने**त्येतदाक्षिप्यते । अस्य हि नियमस्य प्लीहानावित्यादिप्रयोजनम्, तच्चान्यथा सिध्यति । अङ्गाधिकारे हन्ग्रहणं स्त्रीग्रहणं चास्ति । **एङः पदान्तादि**ति पदाधिकारे संग्रहणम् । **वा पदान्तस्ये**त्यतः पदग्रहणानुवर्तनात्—**उदः स्थास्तम्भोरि**ति पूर्वसवर्णः पदाधिकारे विधीयते । **पदाङ्गाधिकार** इत्यत्र च केवलपदाधिकारोऽपि ग्रहीष्यते, उत्तरपदाधिकारोऽपि । ततश्च प्लीहानावित्यादिषु दोषो न भविष्यति । न हि प्लीहानावित्यत्र हनित्यङ्गं नापि तदुत्तरपदमिति प्रश्नः ॥

(उद्योतः) केवलपदाधिकारोऽपीति । अन्यथाऽसन्देहार्थमुत्तरपदेत्येव वदेदिति भावः ॥

भाष्ये—नापीति । समासचरमावयवे तस्य रूढत्वादिति भावः ॥

(परिभाषानावश्यकत्वलाघवभाष्यम्)

तन्न वक्तव्यं भवति ॥

(प्रदीपः) **तन्न वक्तव्यमिति** । **पदाङ्गाधिकार** इत्येतदित्यर्थः । **अलैवानर्थकेने**ति वचनादर्थवता तदन्तविधिसद्भावादिति भावः ॥

(उद्योतः) नन्वेवं तदन्तविध्यभावे वृत्रहणावित्याद्यसिद्धिः । तदन्तविधौ तु प्लीहानावित्यत्र दोषोऽत आह—अलैवेति ॥

(आक्षेपभाष्यम्)

किं पुनरत्र ज्यायः ?

(समाधानभाष्यम्)

तदन्तविधिरेव ज्यायान् । इदमपि सिद्धं भवति—परमातिमहान् । एतद्धि नैव तत्, नापि तदुत्तरपदम् ॥

(प्रदीपः) **तदन्तविधिरेवेति** । प्राथमकल्पिकः सूत्रेणैव तदन्तविधिः । स एव त्वलैवानर्थकेनेति नियम्यते ॥ **परमातिमहानिति** । परमश्चासावतिमहानिति समासः । तत्र परमादिर्महच्छब्दो न भवति, नापि महच्छब्दोत्तरपदः, अतिमहच्छब्दोत्तरपदत्वादिति सान्तमहत इति दीर्घो न स्यात् ।

अनेनैव न्यायेनोगिल्लक्षणो नुमागमोऽपि न स्यात् । तदन्तविधिना तु भवति ॥

(उद्द्योतः) ननु वार्तिकोक्तोऽपि फलतस्तदन्तविधिरेवेत्यत आह—प्राथमेति । सौत्रतदन्तविधिरेव ज्यायान्, न तु वार्तिकोक्तोत्तरपदस्येत्यंश इति नियम आवश्यक इति भावः ॥ परमादिरिति । परमादिः समास उद्देश्यः, महच्छब्दो न भवतीति विधेयं बोध्यम् ॥

(४२१ प्रयोजनभाष्यवार्तिकम् ॥ ५ ॥)

॥ * ॥ अनिनस्मन्ग्रहणानि च ॥ * ॥

(भाष्यम्)

अनिनस्मन्ग्रहणानि चार्थवता चानर्थकेन च तदन्तविधिं प्रयोजयन्ति ॥

अन्—राज्ञेत्यर्थवता । साम्नेत्यनर्थकेन ॥

इन्—दण्डीत्यर्थवता । वाग्मीत्यनर्थकेन ॥

अस्—सुपया इत्यर्थवता । सुस्रोता इत्यनर्थकेन । अस् ॥

मन्—सुशर्मा - इत्यर्थवता । सुप्रथिमा - इत्यनर्थकेन ॥

(प्रदीपः) सुस्रोता इति । अनागमकानां सागमका आदेशा इत्याश्रयणादस आनर्थक्यम् । अर्थवतो ह्यागम इति न्यायाश्रये त्वर्थवानेव अस् ॥

(उद्द्योतः) भाष्ये—अनिनिति । अल्लोपोऽनः, इन्हन्पूषेति, अत्वसन्तस्य, मन इत्यादिषु वर्तमानानीत्यर्थः ॥ अर्थवानेवासिति । इदं चिन्त्यम्, कृते आगमे तद्विशिष्टस्यैवार्थवत्ताया न्याय्यत्वात्, अन्यत्र भाष्ये स्पष्टमुक्तत्वाच ॥

(तदन्तसंज्ञापवादनिरूपणम्)

(४२२ अपवादवार्तिकम् ॥ १ ॥)

॥ * ॥ यस्मिन्विधिस्तदादावल्ग्रहणे ॥ * ॥

(भाष्यम्)

यस्मिन्विधिस्तदादाविति वक्तव्यम् ॥

किं प्रयोजनम् ?

"अचि श्नुधातुभ्रुवां य्वोरियङुवङौ" इति इहैव स्यात्—श्रियौ, भ्रुवौ । श्रियः, भ्रुव इत्यत्र न स्यात् ॥

येन विधिस्तदन्तस्य ॥ ७२ ॥

(प्रदीपः) यस्मिन्विधिरिति । तदन्तविध्यपवादस्तदादिविधिः । अत एव विशेषणेन भवति, नान्येन ॥ ७२ ॥

(उद्द्योतः) नान्येनेति । अत एवैको यणचीत्यादौ न दोषः ॥ यस्मिन्विधिरिति वाचनिकमेव । यस्मिन्निति सप्तम्यन्तोपलक्षणम् । सप्तम्यन्तं यत्र विशेषणं तत्रेति यावत् ॥ ७२ ॥

(इति तदन्तविधिः)

(अथ वृद्धसंज्ञाप्रकरणम्)

(६७ वृद्धसंज्ञासूत्रम् ॥ १ । १ । ९ आ. १३ सू.)

वृद्धिर्यस्याचामादिस्तद्वृद्धम् ॥ १।१।७३ ॥

(पदकृत्यनिर्वचनम्)

(आक्षेपभाष्यम्)

वृद्धिग्रहणं किमर्थम् ?

(प्रदीपः) वृद्धिर्यस्या० ॥७३॥ वृद्धिग्रहणमिति । असति वृद्धिग्रहणे कथं सर्वस्य वृद्धसंज्ञा न भवतीति चेत् । यस्याचामादिर्भिन्नजातीयो हल् तद्वृद्धमित्यजादि व्यावर्तितं स्यात् ॥

(उद्द्योतः) वृद्धिर्यस्या० ॥ ७३ ॥ ननु वृद्धिग्रहणाभावे सर्वत्र वृद्धसंज्ञायां विशेषणान्तराणां वैयर्थ्यमेव स्यादिति तन्मात्राक्षेपोऽनुपपन्न इति शङ्कते—असतीति । सङ्कोचे प्रमाणाभावदचूशब्देन सर्वेष्वच्छु गृहीतेषु तदादिः समीपो हलेव भवतीति परिहरति—यस्येति ॥

(समाधानभाष्यम्)

'यस्याचामादिस्तद्वृद्धम्' इतीयत्युच्यमाने 'दात्ताः, राक्षिताः' अत्रापि प्रसज्येत ।

वृद्धिग्रहणे पुनः क्रियमाणे न दोषो भवति ॥

(प्रदीपः) दात्ता इति । असति वृद्धिग्रहणे निर्धारणहेतोर्धर्मस्यानुपादानादादिशब्दः समीपार्थो विज्ञायेत । दत्तशब्दश्चात्र क्रियाशब्दो द्रष्टव्यः । नामधेयस्य तु पक्षे भवत्येव वृद्धसंज्ञा । प्रस्थेऽवृद्धमित्यत्र यदा नामधेयत्वादवृद्धाः पक्षे कर्क्यादियस्तदर्थः प्रतिषेधः स्यात् ॥

(उद्द्योतः) नन्वचामिति निर्धारणे षष्ठी । निर्धारणं च तुल्यजातीयस्येति यस्यादिरचां मध्ये कश्चिदिति विज्ञायमाने दत्तादौ नातिप्रसक्तिरत आह—असतीति ॥ समीपार्थ इति । पूर्वसमीपार्थ इत्यर्थः । एवं च तन्निरूपितसंबन्धे षष्ठी, न तु निर्धारण इति भावः ॥ यस्याचामादिर्हलित्यर्थः स्यादिति तात्पर्यम् ॥ नामधेयस्य त्विति । वा नामधेयस्येति वचनादिति भावः ॥ भाष्ये—अत्रापीति । अणप्रकृतावित्यर्थः ॥ नन्वेवं हलादेः सर्वस्य वृद्धत्वे प्रस्थेऽवृद्धमिति सूत्रे कर्क्यादिप्रतिषेधोऽनर्थकोऽत आह—प्रस्थ इति ॥

(आक्षेपभाष्यम्)

अथ यस्यग्रहणं किमर्थम् ?

(समाधानभाष्यम्)

यस्येति व्यपदेशाय ॥

(प्रदीपः) यस्येति व्यपदेशायेति । संज्ञिन इति शेषः । अन्यथा तच्छब्देन किं प्रत्यवमृश्येत । तदित्यस्यानुपादाने च वृद्धेरेव वृद्धसंज्ञाप्रसङ्गः ॥

(उद्द्योतः) तदित्यस्यानुपादान इति । तदित्यस्याप्यनुपादाने इत्यर्थः ॥ वृद्धेरेवेति । तथा च प्रदेशेषु त्यदादिविषये मुख्यो वृद्धशब्दः, अन्यत्र वृद्धघटिते लाक्षणिक इति वैरूप्यप्रसङ्ग इति भावः ॥

(आक्षेपभाष्यम्)

अथाज्ग्रहणं किमर्थम् ?

(समाधानभाष्यम्)

'वृद्धिर्यस्यादिस्तद्वृद्धम्' इतीयत्युच्यमाने इहैव स्यात्—औपगवीयाः, ऐतिकायनीयाः । इह न स्यात्—गार्गीयाः, वात्सीया इति ।

अज्ग्रहणे पुनः क्रियमाणे न दोषो भवति ॥

(प्रदीपः) **गार्गीया इति** । न हि गार्ग्यशब्दस्य वृद्धिरादिः । किं तर्हि हल् । **मालादीनां** चेत्येतत्तु नामधेयार्थं स्यात् ॥

(उद्द्योतः) ननु मालादीनामिति लिङ्गाद् आदिसहचरिता यस्य वृद्धिस्तस्यापि संज्ञा स्यादत आह—मालादीति ॥

(आक्षेपभाष्यम्)

अथादिग्रहणं किमर्थम् ?

(उद्द्योतः) भाष्ये—अथादीति । अचामिति षष्ठ्युपादानसामर्थ्यादादिशब्दोऽध्याहरिष्यत इति प्रश्नः ॥

(समाधानभाष्यम्)

'वृद्धिर्यस्याचां तद्वृद्धम्' इतीयत्युच्यमाने सभासंनयने भवः—साभासंनयन इत्यत्रापि प्रसज्येत ।

आदिग्रहणे पुनः क्रियमाणे न दोषो भवति ॥

(प्रदीपः) **सभासंनयन इति** । सति चेहादिग्रहणे आद्यन्तवत्सूत्र एकग्रहणस्य सभासंनयनशब्दः प्रत्युदाहरणम् । असति त्विहादिशब्दे दरिद्रातेरिवर्णान्तलक्षणस्याचोऽभाव एकग्रहणस्य प्रयोजनम् ॥ **अचामिति** तु बहुत्वसंख्याविवक्षार्थं स्यात् ॥

(उद्द्योतः) यस्यावयविनोऽवयवानामचां मध्ये वृद्धिरप्यवयव इत्यध्याहारं विनैवार्थसंभवेऽध्याहारे मानाभाव इत्युत्तराशयः ॥ तत्र प्रसङ्गादादिग्रहणसत्त्वासत्त्वयोराद्यन्तवत्सूत्रस्यैकग्रहणप्रयोजनं दर्शयति—सति चेति । असत्येकग्रहणे पूर्वसहितेऽपि 'भा'शब्दाकारे आदित्वात् सभासंनयनस्यापि वृद्धत्वं स्यादिति भावः ॥ अच इति । एरच इत्यर्थः । तत्र हि धातोरित्यधिकार इति भावः ॥ घञचोः स्वरे विशेषः ॥ नन्वेवं 'यस्य वृद्धिरवयवः' इत्येव सिद्धे 'अचां' इति व्यर्थमत आह—अचामितीति । तथा च राट्शब्दादेर्वृद्धत्वं नेति भावः ॥ कृते त्वादिग्रहणे यत्र वृद्धेरादित्वमेवाजपेक्षया न तु अनादित्वं तस्यैव तेन ग्रहणान्न सभासंनयने दोषः ॥ अचामिति बहुत्वमविवक्षितं, तेन मालीयादिसिद्धिः ॥

(सूत्रोपपादनम्)

(४२३ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ वृद्धसंज्ञायामजसंनिवेशादनादित्वम् ॥ * ॥

(भाष्यम्)

वृद्धसंज्ञायामजसंनिवेशादादिरित्येतन्नोपपद्यते । न ह्यचां संनिवेशोऽस्ति ॥

(प्रदीपः) **न ह्यचामिति** । सर्वस्य प्रातिपदिकस्याज्झल्समुदायरूपत्वात् । अचामित्यनेन केवलानामचां समुदायः संनिवेशरूपो निर्दिष्टः । पौर्वापर्येणावस्थानं—संनिवेशः । स च केवलानामचां नास्ति ॥

(उद्द्योतः) ननु यत्र हल्घटिता अच एव संनिविष्टास्तत्रास्य प्रवृत्तिरस्त्विति, न तु हलन्तरितेष्वस्तु इति मन्यमानः शङ्कते—भाष्ये—वृद्धसंज्ञायामिति ॥ नन्वस्त्येव मातृकापाठे संनिवेशोऽत आह—सर्वस्येति । वृद्धत्वप्रयुक्तकार्यभाज इत्यर्थः । वृद्धत्वनिबन्धनकार्यस्य प्रातिपदिके सत्त्वादिति भावः ॥ अचामित्यनेन केवलानामिति । सर्वपदानां सावधारणत्वेन प्रथमतस्तथैव प्रतीतेरिति भावः । अज्मात्रसंबन्धिनो यस्य समुदायस्यादिर्वृद्धिरित्यर्थः स्यादिति तात्पर्यम् ॥

(आक्षेपबाधकभाष्यम्)

ननु चैवं विज्ञायते—अजेवादिरिति ॥

(प्रदीपः) **ननु चैवमिति** । अच्संनिवेशस्यासंभवादचां मध्येऽजपेक्षया यस्य वृद्धिरादिरिति विज्ञास्यत इत्यर्थः ॥

(उद्द्योतः) ननु प्रथमान्ताच्पदाभावादजेवादिरित्ययुक्तमत आह—अजिति । निर्धारणषष्ठ्याश्रयणात् निर्धारणस्य समानजातीयविषयत्वाच्च तल्लाभ इति भावः ॥ अज्झल्समुदायेऽप्यजपेक्ष एवादिर्ग्रहीष्यते—इति भाष्याक्षरार्थः ॥

(आक्षेपसाधकभाष्यम्)

नैवं शक्यम् । इहैव प्रसज्येत—औपगवीयाः, ऐतिकायनीयाः । इह न स्यात्—गार्गीयाः, वात्सीयाः—इति ॥

(प्रदीपः) **नैवं शक्यमिति** । वृद्धिविशेषणार्था निर्धारणे षष्ठी स्यात् । अचां मध्ये अज्रूपा या वृद्धिरित्याकारस्य निवृत्तिप्रसङ्गः । आकारो ह्यनजेव सन् केवलमच्कार्याणि ग्रहणकशास्त्रेण लभते । ततश्चाश्वलायन इत्यत्र न स्यात् । गार्ग्य इत्यत्र चाकारस्यानच्त्वात् समुदायानादित्वाच्च न स्यात् ॥

(उद्द्योतः) वृद्धिविशेषणार्थेति । तस्याः प्रधानत्वात् 'अचां' इति तस्या एव विशेषणं स्यादित्यर्थः ॥ यदीयाऽऽदिर्वृद्धिरज्मध्यवर्तिनीत्यर्थः । निर्धार्यमाणनिर्धारणावध्योः सजातीयत्वाच्च वृद्धेरच्त्वलाभः । तत्र वृद्धेरच्त्वाव्यभिचारात् विशेषणसामर्थ्येन आक्षरसमाम्नायिकाज्रूपलक्षणवृद्धिपरिग्रह इति भावः ॥ **आकारस्य निवृत्तिप्रसङ्ग इति** । वृद्धसंज्ञानिमित्तत्वनिवृत्तिराकारस्य स्यादित्यर्थः ॥ तत्रासाधारणं प्रत्युदाहरणमाह—ततश्चेति ॥ भाष्योक्तस्य साधारणत्वं ध्वनयन्नाह—समुदायेति । 'यस्य' इति आद्यपेक्षया षष्ठीति भावः ॥

(आक्षेपबाधकभाष्यम्)

एकान्तादित्वं तर्हि विज्ञायते ॥

(उद्द्योतः) एवं 'यस्य' इति आद्युपजनितव्यतिरेके षष्ठीमङ्गीकृत्य 'अचां' इति निर्धारणषष्ठ्यां दोषोऽभिहितः, अज्ञुपजनितव्यतिरेके 'यस्य' इति षष्ठ्यामपि तं वक्तुं भाष्ये—एकान्तादित्वमित्युक्तम् ॥

(आक्षेपसाधकभाष्यवार्तिकम् ॥)

॥ एकान्तादित्वे च सर्वप्रसङ्गः ॥

(भाष्यम्)

इहापि प्रसज्येत—सभासन्नयने भवः—साभासन्नयन इति ॥

(प्रदीपः) एकान्तादित्वे चेति । एकान्ता अवयवा अचः प्रातिपदिकस्य, तेषामचाम् आदिर्वृद्धिर्यस्य तद्वृद्धमित्यर्थः ॥ सर्वप्रसङ्ग इति । न ह्यत्र विशेष उपादीयते—सर्वेषामचामादिर्वृद्धिरिति । ततश्च मध्येऽपि वर्तमान आकारोऽन्याजपेक्षया—आदिरिति सभासन्नयने संज्ञाप्रसङ्गः । आदिग्रहणञ्चान्त्यनिवृत्त्यर्थं स्यात्—खट्वेति ॥

(उद्द्योतः) तद्व्याचष्टे—एकान्ता इति । यस्य प्रातिपदिकस्येति संबन्धः । एवं च यत्प्रातिपदिकावयवभूतानामचामादिर्वृद्धिस्तत्प्रातिपदिकं वृद्धमिति सूत्रार्थः ॥ नन्वादिशब्दोपादानादेव 'सर्वेषामचां' इति लभ्यतेऽत आह—आदिग्रहणमिति ॥

(४२४ समाधानवार्तिकम् ॥ २ ॥)

॥ * ॥ सिद्धमजाकृतिनिर्देशात् ॥ * ॥

(भाष्यम्)

सिद्धमेतत् ॥

कथम् ?

अजाकृतिर्निर्दिश्यते ॥

(प्रदीपः) सिद्धमिति । उभयरूपत्वेऽपि प्रातिपदिकस्याजाकृतिः 'अचाम्'इति वचनादाश्रीयते । विद्यमानाऽपि हलाकृतिर्न विवक्ष्यते । तेनायमर्थः—यस्य शब्दस्य सकलाजपेक्षया वृद्धिरादिस्तद्वृद्धमिति । यथा—पङ्क्तौ ब्राह्मणानामादिमानयेत्युक्ते सतोऽपि शूद्रादीननादृत्य ब्राह्मणजातीयापेक्षया यो ब्राह्मण आदिः स आनीयते ॥

(उद्द्योतः) उभयरूपत्वेऽपीति । अज्झलद्रूपत्वेऽपीत्यर्थः । यस्य-इति नाचां विशेषणम्, तेषामन्यविशेषणत्वात् । नाप्यादेः, व्यवहितत्वात् । किंतु वृद्धेः । अचामिति चादेर्विशेषणं, संनिधानात् । न वृद्धेः, व्यवहितत्वात् । एवं च यस्य वृद्धिरचामादिरित्युक्ते लब्धस्याजपेक्षादित्वस्योपपत्तये मध्ये वर्तमानाऽपि हलाकृतिर्न विवक्ष्यत इति भावः ॥ सकलाजिति । सङ्कोचे मानाभावादिति भावः ॥ सतोऽपीति । आदौ मध्ये वेति शेषः ॥

(आक्षेपभाष्यम्)

एवमपि व्यञ्जनैर्व्यवहितत्वान्न प्राप्नोति ॥

(४२५ समाधानवार्तिकम् ॥ ३ ॥)

॥ * ॥ व्यञ्जनस्याविद्यमानत्वं यथाऽन्यत्र ॥ * ॥

(भाष्यम्)

व्यञ्जनस्याविद्यमानवद्भावो वक्तव्यः । 'यथाऽन्यत्र' । अन्यत्रापि व्यञ्जनस्याविद्यमानवद्भावो भवति ॥

क्वान्यत्र ?

स्वरे ॥

(प्रदीपः) व्यञ्जनस्येति । अचामिति वचनाद्विद्यमानान्यपि व्यञ्जनानि न विवक्षितानीत्यर्थः ॥ यथाऽन्यत्रेति । यथा—स्वरविधावयोग्यत्वाद्व्यञ्जनमविद्यमानवत्, एवमिहाप्यचामिति वचनादित्यर्थः ॥ ह्रस्वनुड्भ्यामिति स्वरविधौ नुड्ग्रहणाल्लिङ्गाद्व्यञ्जनं व्यवधायकमेवेत्युदश्वित्वानिति मतुप उदात्तत्वं न प्रवर्तते ॥

(उद्द्योतः) अचामितीति । केवलाच्संनिवेशासंभवादिति भावः ॥ स्वरविधाविति । स्वरे विधेये-इत्यर्थः ॥ अयोग्यत्वादिति । स्वराणामज्धर्मत्वादिति भावः ॥ अत एव यतोऽनाव इति प्रतिषेधः सार्थकः ॥ नुड्ग्रहणादिति । हल्स्वरप्राप्तिविषयकमेवानाव इति ज्ञापकमिति भावः ॥ अन्यथा नुटोऽविद्यमानवत्त्वादक्षण्वानित्यादौ ह्रस्वादित्येव मतुप उदात्तत्वं सिद्धमिति तद्वैयर्थ्यं स्यादिति तात्पर्यम् ॥

(न्यूनतापूर्तिः)

(५२६ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ वा नामधेयस्य ॥ * ॥

(भाष्यम्)

वा नामधेयस्य वृद्धसंज्ञा वक्तव्या ॥ देवदत्तीयाः । दैवदत्ताः । यज्ञदत्तीयाः । याज्ञदत्ताः ॥

(प्रदीपः) वा नामधेयस्येति । पौरुषेयं नाम गृह्यते ॥

(उद्द्योतः) पौरुषेयमिति । आधुनिकमित्यर्थः ॥ गृह्यत इति । अत्र वार्तिके-इत्यादिः । अत एवैङ्प्राचां देशे इति चरितार्थम्, रूढमात्रस्य नामत्वेन ग्रहणे तद्वैयर्थ्यं स्पष्टमेव । घटीय इति तु गहादित्वात्साधु । घाट इति त्वसाधु । अत एव भाष्ये देवदत्तशब्द उदाहृत इति भावः ॥

(४२७ आक्षेपवार्तिकम् ॥ २ ॥)

॥ * ॥ गोत्रोत्तरपदस्य च ॥ * ॥

(भाष्यम्)

गोत्रोत्तरपदस्य वृद्धसंज्ञा वक्तव्या ॥

कम्बलचारायणीयाः । ओदनपाणिनीयाः । घृतरौढीयाः ॥

(प्रदीपः) कम्बलचारायणीया इति । कम्बलप्रियस्य चारायणस्य शिष्या इत्यर्थः ॥ ओदनपाणिनीया इति । पाणिनोऽपत्यमित्यण् । गाथिविदथीति प्रकृतिभावाट्टिलोपाभावः । पाणिनस्यापत्यं युवेतीञ्, तस्य छात्रा इति विवक्षिते यूनि लुगितीञो लुक्, तेनेञश्चेत्यण् न भवतीति छो भवति ॥

(उद्द्योतः) [युवेतीञिति । प्रकृते च गोत्रशब्देनापत्यमात्रम्, अपत्याधिकारादन्यत्वादिति भावः ॥ नन्वोदनपाणिनीया इत्यत्र वृद्धत्वे छः, असमस्तवदतिदेशे इञन्तत्वादिञश्चेत्यणिति भेदः स्यादत आह—तेनेञश्चेति । येन यूनि विहितो न गोत्रे, तेनेत्यर्थः । इञश्चेत्यत्र गोत्र इति वर्तते । पारिभाषिकं च तत्र गोत्रं गृह्यते इति भावः ॥ यत्तु तेन लुकेति, तन्न । प्रत्ययलक्षणस्य दुर्वारत्वात् ॥]

(४२८ न्यासान्तरेण वार्तिकम् ॥ ३ ॥)

॥ * ॥ गोत्रान्ताद्वाऽसमस्तवत् ॥ * ॥

(भाष्यम्)

गोत्रान्ताद्वा असमस्तवत्प्रत्ययो भवतीति वक्तव्यम् ॥ एतान्येवोदाहरणानि ॥

(उद्द्योतः) भाष्ये-गोत्रान्ताद्वेति । गोत्रप्रत्ययान्तोत्तरपदादित्यर्थः ॥ चारायणो गोत्रान्तो यथाऽसमासे वृद्धत्वाच्छं लभते तथा समासे वृद्धत्वाभावेऽपीत्यर्थः ॥ 'वा' इत्यनेन वृद्धसंज्ञा वा कर्तव्या, इदमुपसङ्ख्यानं वेत्युक्तं भवति ॥

(आक्षेपभाष्यम्)

किमविशेषेण ?

(समाधानभाष्यम्)

नेत्याह ॥

(४२९ शेषवार्तिकम् ॥ ४ ॥)

॥ * ॥ जिह्वाकात्यहरितकात्यवर्जम् ॥ * ॥

(भाष्यम्)

जिह्वाकात्यं हरितकात्यं वर्जयित्वा । जैह्वाकाताः । हारितकाताः ।

(उद्द्योतः) भाष्ये—जिह्वाकात्यादिवर्जनं वृद्धसंज्ञापक्षेऽपि द्रष्टव्यम् ॥

(आक्षेपभाष्यम्)

किं पुनरत्र ज्यायः ?

(समाधानभाष्यम्)

*गोत्रान्ताद्वाऽसमस्तवत्*इत्येव ज्यायः । इदमपि सिद्धं भवति—पिङ्गलकाण्वस्य छात्राः—पैङ्गलकाण्वाः ॥ वृद्धिर्यस्याचामादिस्तद्वृद्धम् ॥ ७३ ॥

(प्रदीपः) पैङ्गलकाण्वा इति । कण्वादिभ्यो गोत्र इत्यण् । वृद्धसंज्ञायां तु छः स्यात् ॥ ७३ ॥

(उद्द्योतः) अणिति । स च केवलेभ्यः काण्व्यादिभ्यश्छस्यापवादः । वृद्धसंज्ञापक्षे तु समुदायस्य कण्वादिषु पाठाभावात् प्रत्ययविधौ तदन्तविधिप्रतिषेधाच्च न तत्प्राप्तिरिति भावः ॥ ७३ ॥

(६८ वृद्धसंज्ञासूत्रम् ॥ १ । १ । ९ आ. १४ सू० ॥)

त्यदादीनि च ॥ १ । १ । ७४ ॥

(अनुवृत्तिनिर्णयः)

(आक्षेपभाष्यम्)

यस्याचामादिग्रहणमनुवर्तते, उताहो न ॥

(उद्द्योतः) त्यदादीनि च ॥ ७४ ॥ भाष्ये—अनुवर्तते ति । पूर्वसूत्रात्परतो गच्छति न वा-इति विचारः ॥

(भाष्यम्)

किं चातः ?

(अनुवृत्तिपक्षे दूषणभाष्यम्)

यद्यनुवर्तते, इह च प्रसज्येत—त्वत्पुत्रस्य छात्राः-त्वात्पुत्राः, मात्पुत्राः । इह च न स्यात्—त्वदीयः, मदीय इति ॥

(प्रदीपः) त्यदादीनि च ॥ ७४ ॥ त्वात्पुत्रा इति । आदिग्रहणानुवृत्त्यन्यथानुपपत्त्योपसर्जनानामपि त्यदादित्वं स्यादिति भावः ॥ अचामित्यस्य तूत्तरार्थैवानुवृत्तिः स्यात्, तत्संबन्धस्येहायोग्यत्वात् । निर्धारणस्य समानजातीयविषयत्वात् ॥ त्वदीय इति । व्यपदेशिवद्भावोऽत्र नास्ति, अप्रातिपदिकेनेति निषेधात् ॥

(उद्द्योतः) ननूपसर्जनानां गणबहिर्भावेन कथं त्यदादित्वमत आह—आदीति । सामर्थ्याद्भूतपूर्वगतिराश्रयिष्यत इति भावः ॥ अचामित्यस्य त्विति । इहादिग्रहणसंबन्ध एव भाष्यतात्पर्यमिति भावः ॥ व्यपदेशिवद्भावेन केवलेऽपि सिद्धमिति इह च नेति भाष्यमयुक्तमत आह—व्यपदेशिवदिति । स निषेधः प्रत्ययविधौ तन्मात्रोपयोगिसंज्ञाविधौ चेति भावः । ७दनाभिल वेदम् ॥

(निवृत्तिपक्षे दूषणभाष्यम्)

अथ निवृत्तम्, "एङ् प्राचां देशे" यस्याचामादिग्रहणं कर्तव्यम् ॥

(अनुवृत्तिपक्षाभ्युपगमभाष्यम्)

तर्ह्यनुवर्तते ॥

(आक्षेपभाष्यम्)

कथं त्वात्पुत्रा मात्पुत्रा इति ?

(समाधानभाष्यम्)

संबन्धमनुवर्तिष्यते—"वृद्धिर्यस्याचामादिस्तद् वृद्धम्" । "त्यदादीनि च" वृद्धसंज्ञानि भवन्ति, वृद्धिर्यस्याचामादिस्तद् वृद्धम् ॥ "एङ् प्राचां देशे" यस्याचामादिग्रहणमनुवर्तते, वृद्धिग्रहणं निवृत्तम् । तद्यथा—कश्चित्कान्तारे समुपस्थिते सार्थमुपादत्ते स यदा निष्कान्तारीभूतो भवति तदा सार्थं जहाति ॥ त्यदादीनि च ॥ ७४ ॥

(प्रदीपः) संबन्धमिति । द्वितीयान्तमेतत् । संबन्धमनुरोत्स्यते-न हास्यतीत्यर्थः । अथवा—संबध्यत इति संबन्धम्, कर्मणि घञ् नपुंसकेऽपि बाधकाभावाद्भवति । वृद्धिग्रहणसंबद्धमादिग्रहणमिहानुवर्तत इति नास्ति तस्य त्यदादिभिः संबन्धः ॥ तद्यथेति । एतद्दर्शयति—स्वरितत्वप्रतिज्ञानादुत्तरसूत्र एव योग्यत्वात् 'यस्याचामादिः' इति संबध्यते 'एङ् यस्याचामादिस्तद् वृद्धम्' इति वाक्यार्थसंपादनाय । इह त्वयोग्यत्वात् संबन्धानुपपत्तिः, तुल्यजातीयस्य निर्धारणात् । त्यदादीनां चाऽरूपत्वाभावाद्यस्याचामादयस्त्यदादय इति संबन्धाभावात् ॥ ७४ ॥

(उद्द्योतः) ननु नपुंसके भावे क्तल्युटौ घञपवादौ । स्त्र्यधिकारात्परतो वाऽसरूपविधिश्च नेति 'संबन्धं' इति नपुंसकप्रथमैकवचनमनुपपन्नमत आह—द्वितीयान्तमिति ॥ नपुंसकेपीति । घञजपाः पुंसीति भावघञ्विषयकं, क्वाचित्कं वेति भावः ॥ चेतनावतस्त्यागोपादाने संभवतः, यस्यादिरित्यस्य तु कथं ते स्यातामत आह—एतदिति । योग्यत्वात्···आदिरित्यस्यैकैत्येकवचनान्तेन संबन्ध इति शेषः ॥ तुल्यजातीयस्येत्युपलक्षणम् । त्यदादीनीत्यनेनादिरित्यस्य भिन्नविभक्तिकत्वाच्चेत्यपि बोध्यम् ॥ ७४ ॥

(६९ वृद्धसंज्ञासूत्रम् ॥ १ । १ । ९ आ. १५ सू. ॥)

एङ् प्राचां देशे ॥ १ । १ । ७५ ॥

(विषयनिर्णयः)

(आक्षेपभाष्यवार्तिकम्)

॥ एङ् प्राचां देशे शैषिकेष्विति वक्तव्यम् ॥

(भाष्यम्)

सैपुरिकी, सैपुरिका । स्कौनगरिकी, स्कौनगरिकेति ॥ एङ् प्राचां देशे ॥ ७५ ॥

इति श्रीमद्भगवत्पतञ्जलिविरचिते व्याकरण-
महाभाष्ये प्रथमाध्यायस्य प्रथमे
पादे नवममाह्निकम् ॥
पादश्च समाप्तः ॥

(प्रदीपः) एङ् प्राचां० ॥ ७५ ॥ कुणिना 'प्राग्ग्रहणमाचार्यनिर्देशार्थं व्यवस्थितविभाषा च' इति व्याख्यातम् । तेन कोडो नामोदग्ग्रामः, तत्र भवः—कौड इत्यणेव भवति ॥ अन्येन तु प्राग्ग्रहणं देशविशेषणं व्याख्यातम् । तेन देवदत्तो नाम वाहीकेषु ग्रामः, तत्र भवो दैवदत्त इत्यवृद्धत्वात् ठञ्ञिठौ न भवतः ॥ भाष्यकारस्तु कुणिदर्शनमशिश्रियत् । सेपुरं स्कोनगरं च वाहीकग्रामौ । तत्र वृद्धत्वाद्वाहीकग्रामेभ्यश्चेति ठञ्ञिठौ भवतः । शैषिकेष्विति वचनादपत्यविकारयोर्वृद्धलक्षणप्रत्ययाभावः । कोडदेवदत्तयोश्चाप्राग्देशवाचिनोर्व्यवस्थितविभाषया न भवतीति । प्राग्देशवाचिनस्तु देवदत्तस्य वृद्धसंज्ञकत्वात् काश्यादित्वात् वृद्धलक्षणौ ठञ्ञिठौ भवतः ॥ ७५ ॥

इत्युपाध्यायजैयटपुत्रकैयटकृते भाष्यप्रदीपे प्रथमाध्यायस्य प्रथमे पादे नवममाह्निकम् ॥
पादश्च समाप्तः ॥

(उद्द्योतः) एङ् प्राचां० ॥ ७५ ॥ कुणिनेति । विधेयसंबन्धलाभात्प्राग्ग्रहणमाचार्यनिर्देशार्थम् । अन्यथा 'प्राग्देशे' इत्येव वदेदिति भावः ॥ लक्ष्यावैषम्याय च व्यवस्थितविभाषाश्रयणम्, तत्फलमाह—तेनेति ॥ अन्येन त्विति । श्रुतान्वये संभवत्यन्येनान्वयोऽनुचित इति तद्भावः ॥ वाहीक । देशविशेषः । तत्र स ग्रामः प्राग्देशबहिर्भूतः । वाहीकदेशश्चोभयसंबद्धः प्राग्देशबहिर्भूतो न । अत एवाव्ययारव्यविति सूत्रे शाकलनाम्नो ग्रामस्य उदीच्यवाहीकोभयरूपता भाष्यकृतोक्ता ॥ एतेनोभयबहिर्भूता वाहीका इत्यपास्तम् ॥ वाहीकग्रामाविति । आद्ये–अस्य 'अप्राग्देशीयौ' इति शेषः पूरणीय इति बोध्यम् ॥ अन्यथा कुणिमताश्रयणेऽस्य प्रमाणता नोपपद्येत ॥ ठञ्ञिठाविति । वाहीकग्रामेभ्यश्चेत्यत्र वृद्धादित्यनुवृत्तेः ॥ प्रागुदग्विभागस्तु–

"शरावत्यास्तु योऽवधेः ।
देशः प्राग्दक्षिणः प्राच्य उदीच्यः पश्चिमोत्तरः"

इत्यमरेण दर्शितः ॥ शरावती चोत्तरतः पूर्वाभिमुखीत्येके । ऐशानीतो नैर्ऋत्यां पश्चिमाभिगामिनी सेत्यन्ये ॥ उभयथाऽपि प्रागुदक्स्वरूपे न विवादः ॥ वाहीकलक्षणं च—

"पञ्चानां सिन्धुषष्ठानामन्तरं ये समाश्रिताः ।
वाहीका नाम ते देशा न तत्र दिवसं वसेत्" ॥

इति कर्णपर्वणि । एवं च धर्मबहिर्भूतत्वाद्वाहीकत्वम् । शतद्रू-विपाशा-इरावती-वितस्ता-चन्द्रभागेति पञ्च नद्यः, सिन्धुः षष्ठः । तन्मध्यदेशो वाहीक इति तद्व्याख्यातारः ॥ कुणिमताश्रयणे शैषिकेष्वित्यस्य वैयर्थ्यम्, व्यवस्थितविभाषयैव सिद्धेः । अतोऽन्यमताश्रयेणैव भाष्यम् । भाष्यप्रामाण्याच्चैतावबाहीकग्रामावपीत्यन्ये ॥ भाष्योक्तव्यवस्थितविभाषाऽतिरिक्ता न व्यवस्थिता-इत्यस्यार्थस्य शैषिकेष्विति ज्ञापकमित्यपरे ॥ अपत्येत्यादि । उदीचां वृद्धादिति नित्यं वृद्धेति चेति सर्वेष्टसिद्धिः ॥ ७५ ॥

हरिदीक्षितपादाब्जसेवनावाप्तबुद्धिना ।
भट्टनागेशविदुषा कृतोऽयं संग्रहो मुदा ॥

इति श्रीशिवभट्टसुतसतीगर्भजनागोजीभट्टकृते भाष्यप्रदीपोद्द्योते प्रथमस्य प्रथमे पादे नवममाह्निकम् ॥

पादश्च प्रथमः समाप्तः ॥

श्रीमद्भगवत्पतञ्जलिमुनिनिर्मितं

पाणिनीयव्याकरणमहाभाष्यम्

विधिशेषरूपं द्वितीयखण्डम् ।

॥ श्रीदधिमथी जयति ॥

श्रीमद्भगवत्पतञ्जलिमुनिरचितं

महाभाष्यम्।

तद्व्याख्यानभूतः कैयटविरचितः प्रदीपः

तद्व्याख्यानभूतो नागेशभट्टविरचित उद्द्योतश्च प्रारब्धः।

तत्र प्रथमाध्याये द्वितीयपादे प्रथममाह्निकम्।

[विविशेषप्रकरणे ङित्प्रकरणम्।]

(६९ ङित्वातिदेशसूत्रम् ॥ १।२।१ आ० १ सूत्रम्)

७५ गाङ्कुटादिभ्यो ऽञ्णिन् ङित् ॥ १।२।१ ॥

(अतिदेशत्वनिर्णयाधिकरणम्)

(५६९ संबन्धपक्षनिराकरणवार्तिकम् ॥ १ ॥)

॥ * ॥ ङित्किद्वचने तयोरभावादप्रसिद्धिः ॥ * ॥

(भाष्यम्) ङित्किद्वचने तयोरभावात् ङकारककारयोरभावात् ङित्त्वकित्त्वयोरप्रसिद्धिः। सता ह्यभिसंबन्धः शक्यते कर्तुम्। न चात्र ङकारककारावितौ पश्यामः। तद्यथा—'चित्रगुर्देवदत्तः' इति यस्य ता गावो भवन्ति स एव ताभिः शक्यतेभिसंबन्धुम् ॥

(प्रदीपः) गाङ्कुटादिभ्यः ॥ १ ॥ चत्वारोत्र पक्षा उपक्षिप्ता भाष्ये—ङित्वकित्त्वसंबन्धप्रतिपादनम्, भावनम्, संज्ञाकरणमतिदेशश्चेति। तत्राद्यपक्षनिराकरणाय वार्तिकमुपन्यस्यति—ङित्किद्वचन इति ॥ सता हीति। विद्यमानेन वस्तुना संबन्धोर्थस्य शक्यते वक्तुम् ॥ न च गाङ्कुटादिभ्यः परस्य प्रत्ययस्य ङकार इत्संज्ञकोस्ति, येन तस्य ङिदिति व्यपदेशः स्यात्। सत्त्वे वा भूतानुवादे प्रयोजनाभावादप्रामाण्यमापतति। न च गाङ्कुटादिभ्यश्चङादेः ङितोऽनेन विधानमुपपद्यते. अञ्णिद्ग्रहणानर्थक्यप्रसङ्गात् ॥

(उद्द्योतः) गाङ्कुटादिभ्यो ॥ १ ॥ अस्य तद्वदतिदेशत्वेन वार्तिकानुत्थानमाशङ्क्याह—चत्वारोत्रेति ॥ उपक्षिप्ताः। दूषणद्वारा साक्षाद्वोक्ता इत्यर्थः ॥ तत्राद्येति। तत्र हि गाङ्कुटादिभ्यः परो ऽञ्णित्प्रत्यय इत्संज्ञकङकारयुक्त इत्यर्थः ॥ तयोरिति तच्छब्देन गुणभूतयोरपि ङकारककारयोर्बुद्धिस्थतया परामर्श इत्याह—भाष्ये—ङकारककारयोरिति। यथा चैतत्तथा पस्पशायामुक्तम् ॥ ङित्वकित्वयोरप्रसिद्धिरिति। तद्व्यवहाराप्रसिद्धिरित्यर्थः। तदाह—येन तस्येति ॥ सत्त्वे वेति। यङादेरिति शेषः ॥ अञ्णिद्ग्रहणवैयर्थ्यापत्त्या च मो राजीतिवल्लोपाभावार्थमनुवाद इति न शङ्क्यम् ॥ ननु शशविषाणादिशब्दैरसतापि विषाणेन शशस्य सम्बन्धः प्रतिपाद्यते इति चेन्न। तद्वदस्याप्यप्रामाण्यप्रसङ्गात् ॥ अञ्णिद्ग्रहणेति। नच वृद्धेदिति विहितण्यङः कर्मणिङश्च व्यावृत्त्यै तद् इति वाच्यम्। गाङ्कुटादिभ्यो ऽनेन तयोर्विधानेपि प्रत्ययाधिकारेस्य पाठाभावेन प्रत्ययत्वाभावात् ञकारणकारयोरित्त्वाप्रवृत्तौ ञ्णितोस्तयोरसंभवात् ॥

(भावनपक्षाभ्युपगमभाष्यम्)

भाव्येते तर्ह्यनेन—गाङ्कुटादिभ्यो ऽञ्णिन् ङिद्भवतीति असंयोगाल्लिट् किद् भवतीति ॥

(प्रदीपः) भाव्येते इति। गाङ्कुटादिभ्यः परो योञ्णित्प्रत्ययः स ङिद्भवति ङकार इत्संज्ञकस्तस्य भवतीत्यर्थः। स तु ङकार आदौ मध्ये अन्ते वेति देशविशेषं नापेक्षते इद्धर्माक्रान्तस्यैव विधानात्। इतां च धर्मो ऽश्रूयमाणानामपि कार्यं प्रति विशेषकत्वम् ॥

(उद्द्योतः) भाष्ये भाव्येते तर्ह्यनेनेति। प्रकरणेनेत्यर्थः ॥ ननु भाव्येते इत्ययुक्तं प्रथमानिर्देशेनादेशविध्यसंभवादत आह—

गाङ्ङिति । गाङादिभ्यः परस्य प्रत्ययस्य तव्यादेः सिद्धत्वाद्विशेषण एव विधितात्पर्यमित्याह—ङकार इति ॥ नन्वेवं लोपस्यावश्यकत्वेन विधानं व्यर्थमत आह—इतां चेति । एवं च कार्यार्थं विधानमिति भावः ॥

(५७० भावनपक्षनिराकरणवार्तिकम् ॥ २ ॥)

॥ * ॥ भवतीति चेदादेशप्रतिषेधः ॥ * ॥

(भाष्यम्) भवतीति चेदादेशस्य प्रतिषेधो वक्तव्यः । ङकारककारावितावादेशौ प्राप्नुतः ॥

(प्रदीपः) भवतीति चेदिति । टित्वकित्त्वमित्त्वानामभावात् ङ इदनन्तरोस्येत्यनन्तरार्थे बहुव्रीह्यभावाच्चादेःपरस्येत्यादेः स्थाने ङकार आदेशः प्राप्नोतीत्यर्थः । ङ इत् ङिदिति तत्पुरुष एव न्याय्यः स्वपदार्थप्राधान्येन तस्यान्तरङ्गत्वाद्बहुव्रीह्यर्थानुपपादाच्च । कुटितेत्यादौ प्रसिद्धङित्वाश्चङादयो यद्यादेशाः क्रियन्ते तदा नैते तदर्थाभिधाने समर्थाः तृङादयश्च नेह शास्त्रे प्रसिद्धाः । अथास्मादेव वचनादपूर्वाः क्रियेरन् तदा ङिच्चेत्यन्त्यस्य स्युः ॥

(उद्योतः) ननु भाष्यमानः सर्वोप्यादेश एवेत्यत्र मानाभावादादेशप्रतिषेध इत्ययुक्तमत आह—टित्त्वेति । अनेनागमत्वं निराकृतम् ॥ उरण्रपरवदनन्तरोस्त्विति चेदत्राह—ङ इत् अनन्तर इति ॥ नन्वेवमपि बहुव्रीहिणा ङिच्छब्देन प्रत्ययाभिधानास्य चानेकाल्त्वात् कथमादेः स्यादत आह—तत्पुरुष इति । न च तस्यादित्वे इत्त्वं व्यर्थं लशक्वतद्धित इत्येव सिद्धेरिति वाच्यम् । अतद्धित इति पर्युदासेन प्रत्ययसंज्ञाकालिकादेरेव तेनेत्त्वविधानात् ॥ अनुपपादोनुपपत्तिस्तामेव दर्शयति—कुटितेत्यादाविति ॥ अथास्मादेवेति । अन्तरतमपरिभाषासंस्कृतादित्यर्थः ॥ अन्त्यस्य स्युरिति । न च ङित्वस्य गुणप्रतिषेधार्थत्वेन चारितार्थ्यात्तत्तन्न्यायेन सर्वादेशो भविष्यतीति वाच्यम् । गुणप्रतिषेधार्थत्वे सर्वादेशत्वं सर्वादेशत्वे च तदर्थत्वमित्यन्योन्याश्रयेण सर्वादेशत्वालाभेऽन्त्यादेशत्वापत्तेरिति भावः । नातङस्तु यथा सर्वादेशत्वं तथोक्तम् ॥

(आक्षेपभाष्यम्)

कथं पुनरित्संज्ञो नामादेशः स्यात् ? ।

(प्रदीपः) कथं पुनरिति । इत्संज्ञो ह्यसन्नेव कार्यमात्रं प्रतिपादयति, आदेशस्तु भावरूपोन्यस्य प्रसक्ते भवति ॥

(आदेशत्वसाधकभाष्यम्)

किं हि वचनान्न भवति ? ।

(प्रदीपः) किं हीति । लोपस्य यथादेशत्वं तथा ङकारस्यापीत्संज्ञकस्य भविष्यतीत्यर्थः । तत्र स्थानिनं निवर्त्य ङकारो निवर्तेत ॥

(आदेशत्वबाधकभाष्यम्)

एवं तर्हि षष्ठीनिर्दिष्टस्यादेशा उच्यन्ते । न चात्र षष्ठीं पश्यामः ॥

(आदेशत्वसाधकभाष्यम्)

गाङ्कुटादिभ्य इत्येषा पञ्चमी अञ्णिदिति प्रथमायाः षष्ठीं प्रकल्पयिष्यति "तस्मादित्युत्तरस्य" इति ॥

(उद्योतः) भाष्ये तस्मादित्युत्तरस्येति । एवं चादेः परस्येत्यस्य प्राप्त्याऽऽदेशपक्षे इष्टासिद्धिः स न युक्त इति भावः ॥

(संज्ञाकरणपक्षाभ्युपगमभाष्यम्)

संज्ञाकरणं तर्हीदम्—गाङ्कुटादिभ्योऽञ्णित ङित्संज्ञो भवतीति । असंयोगाल्लिट् कित्संज्ञो भवतीति ॥

(५७१ संज्ञाकरणपक्षदूषणवार्तिकम् ॥ ३ ॥)

॥ * ॥ संज्ञाकरणे क्ङिद्ग्रहणेऽसंप्रत्ययः शब्दभेदात् ॥ * ॥

(भाष्यम्) संज्ञाकरणे क्ङिद्ग्रहणे असंप्रत्ययः स्यात् ॥ किं कारणम् ? । शब्दभेदात् । अन्यो हि शब्दः क्ङितीति । अन्यः कितीति ङितीति च । तथा किद्ग्रहणेषु ङिद्ग्रहणेषु चानयोरेव संप्रत्ययः स्यात् ॥

(प्रदीपः) संज्ञाकरण इति । अक्तपरिमाणा संज्ञा कृतेति न्यूनातिरिक्तशब्दोच्चारणे संज्ञास्वरूपानुपलम्भात्संज्ञिनामसम्प्रत्ययः । ङित्संज्ञाकरणं तु व्यचेः कुटादित्वमनसीति वचनात्सम्प्रसारणार्थं स्यात् । लिटः कित्संज्ञा च वचिस्वपीति सम्प्रसारणार्था स्यात् ॥ गाङ्कुटादिभ्यस्तर्हि ङित्संज्ञा किमर्था स्याद्, अनर्थिका भवतु, न्यायानुगतेर्थे किं कुर्मः । क्ङितीति चेत्यादिषु यौगिकस्यैव ग्रहणं स्याद् यस्य ककारो ङकारश्चेत्संज्ञकः ॥ अनयोरेवेति । कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसम्प्रत्यय इति न्यायात् । चङादीनां ङित्करणं क्ङित्प्रदेशेषु ग्रहणार्थं स्याद्, यत्र संज्ञारूपानुपलब्धिः ॥

(उद्योतः) संप्रसारणं व्यचेर्ग्रहिज्येत्यनेन ॥ गाङ्कुटादिभ्य इति । व्यचिमेवानुवदेदिति भावः ॥ भाष्ये—क्ङिद्ग्रहण इति । क्ङितीति चेत्यादावित्यर्थः ॥ कृत्रिमेति । उभयगतिमजानत इदं दूषणं बोध्यम् ॥

(तद्वदतिदेशपक्षाभ्युपगमभाष्यम्)

तद्वदतिदेशस्तर्ह्ययम्—गाङ्कुटादिभ्यः अञ्णिन् ङिद्वद्भवतीति । असंयोगाल्लिट् किद्वद्भवतीति ॥

(आक्षेपभाष्यम्)

स तर्हि वतिनिर्देशः कर्तव्यः ॥

(समाधानभाष्यम्)

[न कर्तव्यः ॥]

(आक्षेपसाधक(समाधानबाधक)भाष्यम्)

नह्यन्तरेण वतिमतिदेशो गम्यते ॥

(आक्षेपबाधक(समाधानसाधक)भाष्यम्)

अन्तरेणापि वतिमतिदेशो गम्यते तद्यथा—। "एष ब्रह्मदत्तः" अब्रह्मदत्तं ब्रह्मदत्त इत्याह । ते मन्यामहे—ब्रह्मदत्तवदयं भवतीति । एवमिहाप्य-

ङित्तं ङिदित्याह, ङिद्वदिति गम्यते। अकितं किदित्याह, किद्वदिति गम्यते ॥

(प्रदीपः) **एष ब्रह्मदत्त इति ।** निर्ज्ञाते भेदे तत्कार्यप्राप्तये तद्रूपारोपणं क्रियत इत्यतिदेशगतिः ॥

(उद्द्योतः) भाष्ये एष ब्रह्मदत्त इति । भेदप्रदर्शनम्—**अब्रह्मदत्तमिति** । अस्य 'अयं च' इत्यादिस्तदाह—**निर्ज्ञाते भेदे इति** । निर्णीते भेदे इत्यर्थः ॥ **अतिदेशगतिरिति** । तत्फललाभ इत्यर्थः। आहार्यारोपस्य तत्कार्यबोधनफलकत्वादिति भावः ॥

(५७२ अतिदेशपक्षदूषणवार्तिकम् ॥ ४ ॥)

॥ * ॥ तद्वदतिदेशेऽकिद्विधिप्रसङ्गः ॥ * ॥

(भाष्यम्) **तद्वदतिदेशे अकिद्विधिरपि प्राप्नोति "सृजिदृशोर्झल्यमकिति" स्रक्ष्यति द्रक्ष्यते, अकिल्लक्षणोऽमागमः प्राप्नोति ॥**

(प्रदीपः) **अकिद्विधिप्रसङ्ग इति ।** कार्यातिदेशे तत्प्रतिबद्धानि कार्याणि व्यपदेशमन्तरेणापि भवन्तीति गुणनिषेधादीनामेवातिदेशः । अमागमस्तु स्वाश्रयः केन निवार्यते । यथा ब्राह्मणवदतिदेशः क्षत्रियस्य स्वाश्रयं युद्धादि न निवर्तयति । अकितीति च पर्युदासाश्रयणात्कित्प्रतिबद्धकार्याभावात्स्वाश्रयोऽमागमः स्यात् ॥

(उद्द्योतः) व्यपदेशातिदेशेऽकिद्व्यपदेशविरुद्धाकिद्व्यपदेशस्य स्वाश्रयस्य निवर्तनादाह—**कार्येति । व्यपदेशम् ।** ङित्वादिरूपनिमित्तम्। करणे घञ् । यदि तु अतिदिश्यमानविरुद्धस्वाश्रयकार्याभावोऽतिदेशस्वभावसिद्धः, यथा तत्रैव दृष्टान्ते मद्यपानादिनिवृत्तिरिति न दोषस्तथापि परिहारान्तरस्याभिधास्यमानत्वान्नैतत्सुष्ठुनिरूपितं भगवता॥

(५७३ समाधानवार्तिकम् ॥ ५ ॥)

॥ * ॥ सिद्धं तु प्रसज्यप्रतिषेधात् ॥ * ॥

(भाष्यम्) **सिद्धमेतत् ॥ कथम् ? । प्रसज्यायं प्रतिषेधः क्रियते—किति नेति ॥**

(प्रदीपः) **सिद्धं त्विति ।** प्रसज्यप्रतिषेधे अमागमनिषेध एव किल्कार्यम् ॥

(५७४ आक्षेपवार्तिकम् ॥ ६ ॥)

॥*॥ सर्वत्र सन्नन्तादात्मनेपदप्रतिषेधः ॥*॥

(भाष्यम्) **सर्वेषु पक्षेषु सन्नन्तादात्मनेपदं प्राप्नोति । उच्चुकुटिषति निचुकुटिषति । 'ङितः' इत्यात्मनेपदं प्राप्नोति । तस्य प्रतिषेधो वक्तव्यः ॥**

(५७५ समाधानवार्तिकम् ॥ ७ ॥)

॥*॥ सिद्धं तु पूर्वस्य कार्यातिदेशात् ॥*॥

(भाष्यम्) **सिद्धमेतत् ॥ कथम् ? । पूर्वस्य यत्कार्यं तदतिदिश्यते ॥**

(प्रदीपः) **सिद्धं तु पूर्वस्येति ।** विशिष्टमत्र ङित्कार्यमतिदिश्यते न सर्वमित्यर्थः ॥

(उद्द्योतः) **विशिष्टमत्रेति ।** ततः परस्य यत्तन्नातिदिश्यत इत्यर्थः ॥

(आक्षेपभाष्यम्)

किं वक्तव्यमेतत् ? ॥

(समाधानभाष्यम्)

नहि ॥ कथमनुच्यमानं गंस्यते? । सप्तम्यर्थेऽपि वतिर्भवति । तद्यथा मथुरायामिव 'मथुरावत्' पाटलिपुत्र इव 'पाटलिपुत्रवत्' । एवं ङितीव 'ङिद्वत्', कितीव 'किद्वत्' ॥

(प्रदीपः) **सप्तम्यर्थेपि वतिरिति ।** सप्तम्यर्थे वर्तमानादिवार्थे वतिरित्यर्थः ॥ ननु नेह वतिरुपात्तः तत्कथमयं परिहारः । अयं भावः—यथा न सर्वकार्यप्राप्त्यर्थ एवाब्रह्मदत्ते ब्रह्मदत्तत्वारोपः । अपि तु कस्यचिदेव कार्यस्य लाभार्थः । एवमिहापि व्याख्यानाद्विशिष्टङित्कार्यातिदेशार्थ एवाङ्णितः प्रत्ययस्य तद्रूपासङ्गः । उपदेशग्रहणानुवृत्त्या चोपदेशे यो ङित्तस्मादात्मनेपदमिति सामर्थ्यात्पूर्वस्य कार्यातिदेशोऽयम् ॥

(उद्द्योतः) सप्तम्यर्थे वतेरविधानादाह—**सप्तम्यर्थ इति ।** यद्यपि सप्तम्यर्थवत्यन्तैकदेशस्तदर्थे प्रयुक्तः सत्या सत्यभामेति वदित्यपि भाष्याशयो वक्तुं शक्यस्तथापि **सार्वधातुकमिति** सूत्रविषये पचेतामित्यादावातो ङित इति स्वकार्यस्यातिदेशानापत्तिरत आह—**अयंभाव इति । तद्रूपासङ्गः** तद्रूपारोप इत्यर्थः ॥ निर्लिङ्गं व्याख्यानमयुक्तमत आह—**उपदेशेति** ॥ **पूर्वस्येति ।** परभिन्नस्येत्यर्थः । भाष्ये **सप्तम्यर्थेपी**त्यपिना षष्ठ्यर्थसंग्रहः। तेनोभयसिद्धिः । **तेन तुल्यमिति** वत्यन्तैकदेशत्वाभावे तात्पर्यात् । तेन ततः परस्य यत्कार्यं तन्नेति बोध्यम् ॥

(पृथगनुबन्धप्रयोजनाधिकरणम्)

(आक्षेपभाष्यम्)

अथ किमर्थं पृथक्ङित्कितौ क्रियेते, न सर्वं किदेव स्यात्, ङिदेव वा ॥

(प्रदीपः) **अथ किमर्थमिति ।** कार्यार्थत्वादनुबन्धासङ्गस्यैकेनैवानुबन्धेन गुणनिषेधादेः सिद्धत्वादनुबन्धभेदोनर्थक इति प्रश्नः । एकस्य चानुबन्धस्य करणेऽतिदेशोपि भेदेन न कर्तव्यः ॥

(उद्द्योतः) **अनुबन्धभेद** इत्यस्य प्रत्ययादावित्यादिः ॥ **अतिदेशोपि भेदेनेति ।** अत्र प्रकरणे इत्यादिः। **अपिना** तदन्यप्रदेशेषु चोभयग्रहणं न कर्तव्यं भवतीति सूचितम् ॥

(५७६ प्रयोजनवार्तिकम् ॥ ८ ॥)

॥ * ॥ पृथगनुबन्धत्वे प्रयोजनं वचिस्वपियजादीनामसंप्रसारणं सार्वधातुकचङादिषु॥ * ॥

(भाष्यम्) पृथगनुबन्धत्वे प्रयोजनं वचिस्वपियजादीनामसंप्रसारणं सार्वधातुके चङादिषु च॥ सार्वधातुके प्रयोजनम्—यथेह भवति सुप्तः सुप्तवानिति, एवं 'स्वपितः, स्वपिथः' इत्यत्रापि प्राप्नोति॥चङादिषु च प्रयोजनम्।के पुनश्चङादयः?॥

चङङ्नजिङ्ङ्वनिबथङ्नङः॥ चङ्—यथेह भवति 'शूनः शूनवानिति, एवम् 'अशिश्वियत्' अत्रापि प्राप्नोति॥ अङ्—यथेह भवति शून उक्त इति। एवम् 'अश्वद् अवोचद्' अत्रापि प्राप्नोति॥ नजिङ्—यथेह भवति सुप्तः सुप्तवान् इति, एवं 'स्वप्नग्' इत्यत्रापि प्राप्नोति॥ ङ्वनिप्—यथेह भवतीष्टमिष्टवानिति, एवं 'यज्वा' अत्रापि प्राप्नोति॥ अथङ्—यथेह भवत्युषित इति, एवम् 'आवंसथः' अत्रापि प्राप्नोति॥ नङ्—यथेह भवतीष्टमिति, एवं 'यज्ञः' अत्रापि प्राप्नोति॥

(प्रदीपः) आवसथ इति॥ रुदिविदिभ्यां ङिदित्यतो ङिदिति वर्तमाने उपसर्गे वसेरित्यथप्रत्ययः॥

(उद्द्योतः) श्वेर्विभाषा धेट्श्व्योरिति चङ्। जस्तम्भिवचेरङ् च॥ वचेरस्यतिवक्तीत्यङ् वचउमित्युम्। सर्वत्र ङित्त्वे कित्त्वे वा दोषाः। यथेह भवतीति भाष्यस्य—यथेह शून इत्यादौ सम्प्रसारणं भवति तथा चङादावपि स्यादित्यर्थः। भाष्ये—अथङ् इति। एवमानुपूर्वीक एव प्रत्यय इति भावः॥ अन्यथा फलाभावात् उपसर्गे वसेरित्यत्र ङिदित्यननुवृत्तौ भाष्यासङ्गतिः स्पष्टैवेति केचित्॥

(५७७ प्रयोजनवार्तिकम् ॥ ९ ॥)

॥ * ॥ जाग्रोगुणविधिः ॥ * ॥

(भाष्यम्) जागर्तेरगुणविधिः प्रयोजनम्।यथेह भवति—जागृतः जागृथ इत्यङितीति पर्युदासः। एवं जागरितः जागरितवानित्यत्रापि प्राप्नोति॥

(प्रदीपः) जाग्र इति। किति गुण इष्यते, न ङिति। एवं च विषयविभागः पृथगनुबन्धोपादानादेव लभ्यते॥

(भाष्यम्) अपर आह—"जाग्रो गुणविधिः।" जागर्तेर्गुणविधिः प्रयोजनम्। यथेह भवति—जागरितः जागरितवानिति। एवं जागृतः जागृथ इत्यत्रापि प्राप्नोति॥

(उद्द्योतः) भाष्ये अपर आहेति। यद्यपि सर्वत्र ङित्त्वे कित्त्वे वा सूत्रे तत्तत्पदमेवोपादातव्यम्। एवं च सर्वथा जागरित इत्यादौ गुणभवनमसिद्धमिति भाष्यदृष्टान्तासंगतिस्तथापि जागरित इत्येतल्लिङ्गार्थमन्यतरदपि यदि तत्सूत्रे न क्रियते तदायं ग्रन्थ इत्याहुः॥

(५७८ प्रयोजनवार्तिकम् ॥ १० ॥)

॥ * ॥ कुटादीनामिट्प्रतिषेधः ॥ * ॥

(भाष्यम्) कुटादीनामिट्प्रतिषेधः प्रयोजनम्। यथेह भवति—'लूत्वा, धूत्वा' इति "श्र्युकः किति" इतीट्प्रतिषेधः, एवं 'नुविता, धुविता' अत्रापि प्राप्नोति॥

(प्रदीपः) नुवितेति। नू स्तुतौ। धुवितेति धू विधूनने। कितीति सप्तमीनिर्देशात् इट्प्रतिषेधस्याप्यतिदेशः स्यादित्युपन्यासः। नलिट्प्रतिषेधः पूर्वस्य कार्यम्॥

(उद्द्योतः) नू धू, कुटादी॥ सप्तमीनिर्देशादिति। वस्तुतः पूर्वस्य कार्यातिदेश इत्यस्य परभिन्नकार्ये इत्यर्थः। स्वकार्ये त्विष्यत एवातो ङित इत्यादीति बोध्यम्॥

(५७९ प्रयोजनवार्तिकम् ॥ ११ ॥)

॥ * ॥ क्त्वायां कित्प्रतिषेधश्च ॥ * ॥

(भाष्यम्) [क्त्वायां कित्प्रतिषेधश्च प्रयोजनम्] किं 'च' इट्प्रतिषेधः?॥

नेत्याह। अदेशेयं चः पठितः—"क्त्वायां च कित्प्रतिषेध" इति॥ यथेह भवति—देवित्वा सेवित्वेति "न क्त्वा सेट्" इति कित्त्वप्रतिषेधः। एवं 'कुटित्वा, पुटित्वा' अत्रापि प्राप्नोति॥

(प्रदीपः) कुटित्वेति। न क्त्वा सेडिति निषेधो विशेषानुपादानादौपदेशिकवदातिदेशिकस्यापि कित्त्वस्य स्यात्। अथ वा यदप्राप्तं कार्यं तदतिदिश्यते इति क्त्वाप्रत्यये कित्त्वातिदेश एव न स्यात्॥

(उद्द्योतः) ननु न क्त्वेति निषेध औपदेशिकस्यैवेति न दोषोऽत आह—न क्त्वेति॥ नन्वौपदेशिकस्य प्रथमोपस्थितत्वेन तन्निषेधेन चरितार्थमातिदेशिकं न निषेधेदित्यरुचेराह—अथवेति॥ न स्यादिति। कुटादिभ्यः परस्य कित्त्वविधानं त्वन्यत्र चरितार्थं कुटित्वेत्यादौ कित्वप्रतिषेध एव स्यात्। न तु कित्त्वमिति भाष्याक्षरार्थः। एवं च कुटित्वेत्यादौ गुणः स्यात्॥

(यथान्याससमर्थनभाष्यम्)

अथ वा देश एवायं चः पठितः—क्त्वायां कित्प्रतिषेधश्चेट्प्रतिषेधश्च॥ कित्प्रतिषेध उदाहृतम्॥ इट्प्रतिषेधो यथेह भवति 'लूत्वा धूत्वा' "श्र्युकः किति" इति। एवं 'नुवित्वा, धुवित्वा' अत्रापि प्राप्नोति॥

(प्रदीपः) नुवित्वेति। ङित्त्वेनात्र कित्त्वं येननाप्राप्तिन्यायेन बाध्यत इति भावः॥

(उद्द्योतः) ननु पृथगनुबन्धकरणेपि नुवित्वेत्यादौ कथं श्र्युक इति निषेधो न, औपदेशिककित्त्वसत्त्वादित्यत आह—ङित्त्वेनेति॥

(यथान्याससमर्थनबाधकभाष्यम्)

स्यादेतत्प्रयोजनं यद्यस्य नियोगत आतिदेशिकेन ङित्त्वेनौपदेशिकं कित्त्वं बाध्येत॥ सत्यपि

तु ङित्त्वे किदेवैषः। तस्माद्भूत्वा धूत्वेत्येव भवितव्यम्॥ गाङ्कुटादिभ्योऽञ्णिन्ङित्॥ १॥

(प्रदीपः) सत्यपीति। विरोधाभावादतिदेशेन स्वाश्रयस्य कित्त्वस्यानिवर्तनाद् येन नाप्राप्त इति न्यायाभावाच्च। नहि कुटिता कुटितुमित्यादौ कित्त्वे प्राप्ते ङित्त्वारम्भः॥ १॥

(उद्द्योतः) भाष्ये तस्मादिति। एवं च 'अदेशे ऽयं चः' इति स्थितम्॥ १॥

———>o<———

(७० ङित्वातिदेशसूत्रम्॥ १।२।१ आ. २ सू०)

७८ सार्वधातुकमपित्॥ १।२।४॥

(सार्वधातुकपदप्रयोजनाधिकरणम्)

(आक्षेपभाष्यम्)

सार्वधातुकग्रहणं किमर्थम्?॥

(प्रदीपः) सार्वधातुक॥ ४॥ लिङ्गादव्याप्तिरतिव्याप्तिर्वेति प्रदर्शनाय सार्वधातुकग्रहणस्याक्षेपप्रतिसमाधाने भाष्यकारेणोपन्यस्ते।

(उद्द्योतः) सार्वधातु॥ ४॥ लिङ्गादिति। चङादीनां ङित्त्वादित्यर्थः। तुल्यजातीयस्य ज्ञापने तृजादौ ङित्त्वमतिव्याप्तम्। धातुप्रत्ययसामान्यविषये तु ज्ञापकेऽव्याप्तमिति भावः॥

(समाधानभाष्यम्)

अपिदितीयत्युच्यमाने आर्धधातुकस्याप्यनेनापितो ङित्त्वं प्रसज्येत—कर्ता हर्ता॥

(समाधाननिराकरणभाष्यम्)

नैष दोषः। आचार्यप्रवृत्तिर्ज्ञापयति—नानेनार्धधातुकस्यापितो ङित्त्वं भवतीति। यदयमार्धधातुकीयान् कांश्चिद् ङितः करोति चङङ्जिङ्ङ्वनिबथङ्नङः॥

(प्रदीपः) आर्धधातुकीयानिति। अर्धधातुषु भवा इति ठञन्तत्वादन्तोदात्तत्वाभावाद् बह्वचोन्तोदात्ताट्ठञिति ठञभावे वृद्धाच्छो भवति॥ तातङस्तु ङित्त्वं तिपः पित्त्वादप्राप्तमित्यज्ञापकं सार्वधातुकाङित्त्वस्य, ङ्वनिपो ङित्त्वमज्ञापकमस्य हि पित्त्वात् ङित्त्वाप्राप्तिः॥

(उद्द्योतः) आर्धधातुकशब्दस्य चरत्याद्यर्थठगन्तत्वेनान्तोदात्तत्वाद्बह्वचोन्तोदात्तादिति ठञ् प्राप्नोतीत्यत आह—अर्धेति। अर्द्धधातुशब्दस्तत्पुरुषेन्तोदात्तः, ततश्च भवादावर्थे बह्वच इति ठञ् ञित्त्वादाद्युदात्तत्वमिति भावः॥ भवेति। तेषु भवा संज्ञार्धधातुकमित्यर्थः॥ ठञन्तत्वादिति। आर्धधातुकशब्दस्येति शेषः॥ आर्धधातुकसंज्ञायां संज्ञित्वेन भवानार्धधातुकीयानित्यर्थः॥ आर्धधातुक इति यदार्धधातुकानिति वक्तव्ये आर्धधातुकीयानित्युक्तिः प्रियतद्धिता दाक्षिणात्या इति न्यायेनेति बोध्यम्॥ ननु टेङित्त्वेनैव सिद्धे तदादेशतातङो ङित्त्वं सार्वधातुकाङित्त्वस्य ज्ञापकं स्यादत आह—तातङस्त्विति॥ पित्त्वान्ङित्त्वाप्राप्तिरिति। तद्धि सुत्त्वेत्यत्र तुगर्थमनुदात्तार्थं चावश्यकमिति भावः। एवं च पूर्वसूत्रे सहनिर्देशादिहापि तदुच्चारणमिति तात्पर्यम्॥ यद्वा ङ्वनिप्प्रक्षिप्तः ङ्वनिब्भूतकालानामिति च प्रक्षिप्तः पाठ इति तात्पर्यम्॥

(निराकरणबाधकभाष्यम्)

सार्वधातुकेप्येतज्ज्ञापकं स्यात्॥

(निराकरणसाधकभाष्यम्)

नेत्याह॥ तुल्यजातीयस्य ज्ञापकम्॥

कश्च तुल्यजातीयः?॥

यथाजातीयकाश्चङ्ङ्जिङ्ङ्वनिबथङ्नङः॥

कथंजातीयकाश्चैते?॥

आर्धधातुकीयाः॥

(समाधानसाधकभाष्यम्)

यद्येतदस्ति तुल्यजातीयस्य ज्ञापकमिति, चङङौ लुङ्विकरणानां ज्ञापकौ स्याताम्, नजिङ्वर्तमानकालानाम्, ङ्वनिब् भूतकालानाम्, अथङ्शब्द औणादिकानाम्, नङ्शब्दो घञर्थानाम्। तस्मात्सार्वधातुकग्रहणं कर्तव्यम्॥

(उद्द्योतः) लुङ्विकरणानामिति। ते चङ्क्सिच्चिणः॥

(पर्युदासप्रसज्यप्रतिषेधनिर्णयाधिकरणम्)

(आक्षेपभाष्यम्)

किं पुनरयं पर्युदासः—यदन्यत्पित इति, आहोस्वित्प्रसज्यायं प्रतिषेधः—पिन्नेति?।

(प्रत्याक्षेपभाष्यम्)

कश्चात्र विशेषः?।

(५८० आक्षेपवार्तिकम्॥ १॥)

॥ * ॥ अपिद् ङिदिति चेत् शबेकादेशप्रतिषेध आदिवत्त्वात्॥ * ॥

(पर्युदासपक्षेदूषणभाष्यम्)

अपिन् ङिदिति चेत् शबेकादेशे प्रतिषेधो वक्तव्यः। च्यवन्ते प्लवन्ते॥ किं कारणम्?॥ आदिवत्त्वात्। पिदपितोरेकादेशोपित आदिवत्स्यात्। अस्त्यन्यत्पित इति कृत्वा ङित्त्वं प्राप्नोति॥

(प्रदीपः) च्यवन्ते प्लवन्त इति। गुणात्पूर्वं नित्यत्वादन्तरङ्गत्वाच्चैकादेशः। तत्र कृते परस्येहापित आश्रितत्वात्परस्य कार्यं प्रत्यादिवद्भावाद् गुणनिषेधः स्यात् साधारणपरिहाराभिधानाय वार्णादाङ्गमिति नाश्रितम्। प्रसज्यप्रतिषेधे तु ङित्त्वनिषेधः। पूर्वस्य कार्यमिति पूर्वं प्रत्यन्तवत्त्वात् ङित्त्वाभावः। यद्यपि सार्वधातुकावयवस्याकारस्यैकादेशः तथापि परं प्रत्यादिवत्त्वादन्तशब्दः सार्वधातुकमपिद् भवतीति स्यादेव ङित्त्वम्। च्यवे इति चोत्तमैकवचने सर्वस्यैव सार्वधातुकस्यैकादेश इति ङित्त्वप्रसङ्गः॥

(उद्योतः) प्रत्यादिवद्भावादिति । शाब्दफललाभायादिवत्त्वमेव प्राप्नोति, नत्वन्तवद्भावः। तेन हि ङित्त्वाभाव आर्थः फलति नतु शाब्द इति भावः ॥ साधारणेति । व्याश्रयेप्यस्य प्रवृत्तिमङ्गीकृत्येदम् । वस्तुतस्तु विभिन्ननिमित्ते प्रवृत्तावपि विभिन्नस्थानिके न तत्परिभाषाप्रवृत्तिरिति भाष्याशयः ॥ यद्यपीति । अकारयोरेकादेशस्योक्तन्यायेनापित्त्वेप्युभयत आश्रयणेऽन्तादिवत्त्वनिषेधात्सार्वधातुकत्वाभावेन न ङित्त्वम् । परादिवद्भावेन तु न सार्वधातुकत्वलाभः परस्य सार्वधातुकावयवत्वेपि तत्त्वाभावादिति भावः ॥ परं प्रतीति। परं समुदायं प्रतीत्यर्थः । एकादेशस्थानिनावचौ पूर्वपरौ ययोः समुदाययोरन्तादी एकादेशोपि तयोरेवान्तादिवदिति सूत्रार्थ इति भावः ॥ अभ्युपेत्यापि अचावेव प्रत्यन्तवत्वं दोषान्तरमाह—च्यवे इति ॥ इलः श्नः सूत्रभाष्ये तु 'ङिच्च पिन्न पिच्च ङिच्च' इत्यर्थसिद्ध्यर्थं प्रसज्यप्रतिषेध एवाश्रितः ॥

(प्रसज्यप्रतिषेधाभ्युपगमभाष्यम्)

अस्तु तर्हि प्रसज्यप्रतिषेधः—पिन्नेति ।

(५८१ आक्षेपवार्तिकम् ॥ २ ॥)

॥ * ॥ न पिन्ङिदिति चेदुत्तमैकादेशप्रतिषेधः ॥ * ॥

(भाष्यम्) न पिन्ङिदिति चेदुत्तमैकादेशे प्रतिषेधः प्राप्नोति। तुदानि लिखानि ॥ किं कारणम्? । आदिवत्त्वादेव । पिदपितोरेकादेशः पित आदिवत् स्यात् । तत्र पिन्नेति प्रतिषेधः प्राप्नोति ॥

(प्रदीपः) तुदानीति । यद्यप्युत्तमस्य पित्त्वं तथापि तद्भक्तत्वादाटः पिदवयवस्यैकादेशः पित उत्तमस्यादिवदिति स्यान्ङित्त्वनिषेधः । तुद इत्यत्र च सर्वस्यैव पित एकादेशः पित आदिवदिति ङित्त्वप्रतिषेधप्रसङ्गः ॥

(उद्योतः) यद्यप्युत्तमस्येति । आडुत्तमस्येत्यस्योत्तमस्याडागमो भवति यस्माद् स पिदित्यर्थ इति भावः ॥ नन्वाडायमेकादेशो, न च स पिदवयवो, भिन्नेव हि पिद्, इत्यत उक्तम्—तद्भक्तत्वादिति । शास्त्रेण तद्भक्तत्वबोधनादित्यर्थः ॥

(सिद्धान्तिभाष्यम्)

यथेच्छसि तथास्तु ॥

(आक्षेपस्मारणभाष्यम्)

ननु चोक्तमुभयथापि—दोष इति ॥

(समाधानभाष्यम्)

उभयथापि न दोषः । एकादेशः पूर्वविधौ स्थानिवद्भवतीति स्थानिवद्भावाद्व्यवधानम् ॥ सार्वधातुकमपित् ॥ ४ ॥

(प्रदीपः) स्थानिवद्भावादिति । यथा स्थानिकाले यथायोगं गुणप्रवृत्तिनिवृत्ती तथाऽऽदेशेपि कृतेऽव्यवधानबुध्या भवतः ॥

(उद्योतः) ङित्त्वविधिप्रतिषेधौ न पूर्वस्य कार्ये इत्यत आह—यथेति ॥ अव्यवधानबुध्येति । शप्श्नयोरव्यवधानबुद्धेत्यर्थः ॥ भाष्ये—व्यवधानमिति । ङित्त्वप्रयुक्ते निषेधे कर्तव्ये शपा व्यवधानमित्यर्थः ॥ ४ ॥

(इति ङित्प्रकरणम् ॥)

(अथ कित्प्रकरणम् ॥)

(७१ कित्त्वातिदेशसूत्रम् ॥ १ । २ । १ आ. ३ सू.)

७९ असय्ँयोगाल्लिट्कित् ॥१।२।५॥

(५८२ सिद्धान्तवार्तिकम् ॥ १ ॥)

॥ * ॥ ऋदुपधेभ्यो लिटः कित्वं गुणाद्विप्रतिषेधेन ॥ * ॥

(भाष्यम्) ऋदुपधेभ्यो लिटः कित्त्वं गुणाद्भवति विप्रतिषेधेन । ववृते ववृधे ॥

(प्रदीपः) असंयोगात् ॥ ५ ॥ ऋदुपधेभ्य इति । बिभिदतुः बिभिदुरित्यादौ कित्त्वं नित्यं गुणस्त्वनित्यः ववृतइत्यादौ तु द्वयोरप्यनित्यत्वं तत्र परत्वाद् गुणप्रसङ्गः पूर्वविप्रतिषेधाश्रयेण निवार्यते ॥

(उद्योतः) असंयोगात् ॥५॥ ऋदुपधेभ्य इति विशिष्योक्तिः किमर्थेत्यत आह—बिभिदतुरिति । यद्यपि गुणे कृते कित्कार्याभावात् तदप्राप्तौ कित्त्वमनित्यमिति शक्यं वक्तुम् । तथापि कृताकृतप्रसङ्गमात्रेण नित्यत्वमिति भावः ॥ द्वयोरप्यनित्यत्वमिति । कित्त्वे कृते प्रतिषेधाद् गुणोऽनित्यः गुणे संयोगात्परत्वात्कित्त्वमनित्यमिति भावः ॥

(५८३ वार्तिकम् ॥ २ ॥)

॥ * ॥ उक्तं वा ॥ * ॥

(भाष्यम्) किमुक्तम्? । * 'न वा क्सस्यानवकाशत्वादपवादो गुणस्य * इति ॥

(प्रदीपः) न वा क्सस्येति । यथा क्सस्य कित्करणसामर्थ्याद् गुणो बाध्यते तथेहातिदेशसामर्थ्यादित्यर्थः ॥

(उद्योतः) ननु क्सस्यानवकाशत्वादित्ययुक्तम् । गुणे कृतेऽपि भूतपूर्वगत्या क्सप्राप्तेरत आह—यथेति । अन्यथा जातस्य निषेधायोगेन विशिष्टविधानं व्यर्थं स्यादिति च्व्यवस्थायां प्राप्तगुणं बाधित्वा क्स एवेति भावः ॥ तथेहेति । ऋदुपधविषयैतल्लक्षणोपप्लवप्रापितनिषेधसामर्थ्यादित्यर्थः ॥

(अनवकाशत्वबाधकभाष्यम्)

विषम उपन्यासः । युक्तं तत्र यदनवकाशं कित्करणं गुणं बाधते ॥ इह पुनरुभयं सावकाशम्—कित्करणस्यावकाशः—ईजतुः, ईजुः । गुणस्यावकाशः—वर्तिता वर्द्धिता । इहोभयं प्राप्नोति—ववृते ववृधे । परत्वाद् गुणः प्राप्नोति ॥

(प्रदीपः) **युक्तं तत्रेति**। क्तस्य कित्करणे प्रयोजनान्तराभावः। इह तु सम्प्रसारणविधौ कृतार्थत्वाद् दुर्बलेनातिदेशेन प्राप्यमाणो गुणनिषेधो दुर्बलत्वान्न तद्विधिना सह स्पर्धते तातङ्न्यायेन॥

(उद्द्योतः) ननु विध्युन्मूलकत्वेन निषेधस्य बलवत्त्वमयं च कार्यातिदेशोऽत आह—**दुर्बलेनेति**। अतिदेशदुर्बलत्वे हेतुः कृतार्थत्वादित्यन्तः॥ **तातङ्न्यायेनेति**। तातङि गुणादिनिषेधार्थत्वेन ङित्त्वस्य चरितार्थत्वादनेकाल्शिदित्यनेन यथाऽपवादङिच्चेत्यस्य बाधस्तथेत्यर्थः॥ केचित्तु इदं न युक्तं विचति गृह्णातीत्यादौ सम्प्रसारणेन चरितार्थतया ङित्त्वस्य गुणनिषेधातिदेशानापत्तेः, अतिदेशोपप्लुततद्विषयनिषेधसामर्थ्याद् गुणबाध इत्येवं वार्त्तिकस्य कैयटेन व्याख्यानादेतदाशयानभिज्ञैकदेशिनश्च **विषम** इत्यादिर्ग्रन्थ इत्याहुः॥५

(भाष्यम्) **इदं तर्ह्युक्तम्—"इष्टवाची परशब्दः" इति। विप्रतिषेधे परं यदिष्टं तद्भवति इति॥ असंयोगाल्लिट्कित्॥ ५॥**

(प्रदीपः) **इष्टवाचीति**। सूत्रकारेणैवायमर्थः संगृहीतः स तु स्मर्तव्य इत्यर्थः॥ ५॥

(७२ कित्वातिदेशसूत्रम्॥ १। २। १ आ. ४ सू.)

८० इन्धिभवतिभ्यां च॥ १। २। ६॥

(आक्षेपभाष्यम्)

किमर्थमिदमुच्यते ?॥

(प्रदीपः) **इन्धि॥६॥ किमर्थमिति**। विनापि सूत्रेणेष्टं सिध्यति सत्यपि चेष्टं न सिध्यति। बभूवेत्यजलक्षणत्वाद् वृद्धेरिग्लक्षणत्वाभावात्प्रतिषेधाप्रसङ्गात्। गुणमात्रनिषेध एव तु बभूविथ अहं बभूवेति च णित्त्वाभावपक्षे स्यादिति प्रश्नः॥

(उद्द्योतः) **इन्धिभवति**॥ ६॥ इष्टासिद्धिमेव दर्शयति—**बभूवेत्यजिति**॥ ननु कित्त्वविधानसामर्थ्यादनिग्लक्षणाया अपि वृद्धेः प्रतिषेधो भविष्यतीत्यत आह—**गुणमात्रेति**। एवं च तन्निषेधेनास्य चारितार्थ्येनानिग्लक्षणवृद्धिनिषेधसत्त्वे मानाभाव इति भावः॥

(समाधानभाष्यम्)

इन्धेः संयोगार्थं वचनम्। भवतेः पिदर्थम्।

(प्रत्याख्यानभाष्यम्)

अयं योगः शक्योऽवक्तुम्।

(आक्षेपभाष्यम्)

कथम्?।

(५८४ प्रत्याख्यानवार्तिकम्॥ १॥)

॥ * ॥ इन्धेश्छन्दोविषयत्वाद् भुवो वुको नित्यत्वात्ताभ्यां किद्वचनानर्थक्यम्॥ * ॥

(भाष्यम्) **इन्धेश्छन्दोविषयो लिट्। नह्यन्तरेण छन्द इन्धेरनन्तरो लिट् लभ्यः। आमा भाषायां भवितव्यम्॥ भुवो वुको नित्यत्वात्। भवतेरपि नित्यो वुक् कृते गुणे प्राप्नोति, अकृतेपि प्राप्नोति। ताभ्यां किद्वचनानर्थक्यम्। ताभ्यामिन्धिभवतिभ्यां किद्वचनमनर्थकम्॥ इन्धिभवतिभ्यां च॥ ६॥**

(प्रदीपः) **इन्धेरिति**। भाषायां लिट आमा व्यवधानाच्छन्दस्यमन्त्र इत्याम्प्रतिषेधादेतदुक्तम्। न त्वस्य भाषायां प्रयोगाभावः। तत्र **छन्दस्युभयथेति** लिटः सार्वधातुकत्वात्समीध इति ङित्त्वान्नलोपः। आर्धधातुकत्वाच्च श्नमभावः। **व्यत्ययो बहुलमिति** वचनाद्वा॥ **नित्यो वुगिति**। **ओः सुपीत्यत** ओरिति नानुवर्तत इति भावः। एकदेशविकृतस्यानन्यत्वाच्च शब्दान्तरप्राप्त्यभावः। सत्यामपि वा शब्दान्तरप्राप्तौ कृताकृतप्रसङ्गित्वाद्वुको नित्यत्वं वुकि कृते गुणस्य प्राप्तिरेव नास्तीति नैतयोस्तुल्यबलत्वम्॥ ६॥

(उद्द्योतः) ननु छन्दस्येव **समीधे** इत्यादौ नलोपार्थं कित्त्वमावश्यकमत आह—**तत्रेति**॥ नन्वेवं विकरणः स्यादत आह—**आर्धेति**॥ नन्वेवं शब्दान्तरप्राप्तिः क्वापि न स्यादत आह—**सत्यामपीति**। श्रौतरूपमादायेति भावः॥ ६॥

(७३ कित्वातिदेशसूत्रम्॥ १। २। १ आ. ५ सू.)

८१ मृडमृदगुधकुषक्लिशवदवसः क्त्वा॥ १। २। ७॥

(आक्षेपभाष्यम्)

किमर्थं मृडादिभ्यः परस्य क्त्वः कित्त्वमुच्यते। न किदेव हि क्त्वा ?।

(समाधानभाष्यम्)

"न क्त्वा सेड्" इति प्रतिषेधः प्राप्नोति तद्बाधनार्थम्॥

(लाघवभाष्यम्)

यदि तर्हि मृडादिभ्यः परस्य क्त्वः कित्त्वमुच्यते नार्थो 'न क्त्वा सेड्' इत्यनेन कित्त्वप्रतिषेधेन। इदं नियमार्थं भविष्यति—मृडादिभ्य एव परस्य क्त्वः कित्त्वं भवति नान्येभ्य इति॥

(प्रदीपः) **मृड॥७॥मृडादिभ्य एवेति**। विपरीतनियमस्तु व्याख्यानान्न भविष्यति मृडादिभ्यः क्त्वैव किद्भवतीति। नह्यनिष्टार्था शास्त्रप्रवृत्तिर्लक्ष्यमूलकत्वाद्व्याकरणस्मृतेः॥

(उद्द्योतः) **मृडमृद**॥ ७॥ **विपरीतेति**। विशेषणीभूतमृडादिसंकोचस्य न्याय्यत्वादयं न्याय्य इति भावः। न च लोके प्रधानसंकोच एव न्याय्यत्वेन व्यवह्रियते 'राज्ञः संकोचः कार्यः' इति, राजनिमित्तं स्वव्यवहारसंकोचस्तदविस्तररूपः कर्तव्य इति तदर्थात्॥ समाधत्ते,—**व्याख्यानादिति**॥

(आक्षेपभाष्यम्)

यदि नियमः क्रियते, इहापि तर्हि नियमात्र प्राप्नोति—लूत्वा पूत्वा। अत्राप्यकित्त्वं प्राप्नोति॥

(प्रदीपः) लूत्वेति । क्त्वाप्रत्ययमात्रस्य नियमः स्यात् । कित्त्वं तु क्त्वातोसुन्कसुन इत्यादौ विशेषणार्थं स्यात् ॥

(उद्योतः) विशेषणार्थं स्यादिति । सुत्वेत्यादि च व्यावर्त्यं स्यादित्याहुः । अस्यानर्थकत्वेनैव वारणाद्विशेषणव्यावर्त्यं चिन्त्यम् । वस्तुतः क्त्वः कित्वसामर्थ्यादेव तुल्यजातीयापेक्षो नियम इति बोध्यम् ॥

(आक्षेपबाधकभाष्यम्)

तुल्यजातीयस्य नियमः ॥
कश्च तुल्यजातीयः? ॥
यथाजातीयको मृडादिभ्यः परः क्त्वा ॥
कथंजातीयकश्च मृडादिभ्यः परः क्त्वा? ॥
सेट् ॥

(आक्षेपसाधकभाष्यम्)

एवमप्यस्त्यत्र कश्चिद्विभाषितेट् सोनिटां नियामकः स्यात् ॥

(प्रदीपः) एवमपीति । क्लिशः क्त्वानिष्ठयोरिति विकल्पेनेड्विधानात् ॥

(आक्षेपबाधकभाष्यम्)

अस्तु तावद्ये सेटस्तेषां ग्रहणं नियमार्थम् । य इदानीं विभाषितेट् तस्य ग्रहणं विध्यर्थं भविष्यति ॥ रुदविदमुषग्रहिस्वपिप्रच्छयोः सन्नर्थं ग्रहणम् । किदेव हि क्त्वा ॥ मृडमृदगुधकुष—॥ ७ ॥

(प्रदीपः) अस्तु तावदिति । मृडमृदवदर्थसां क्त्वः कित्त्वविधानं नियमार्थं गुधकुषक्लिशीनां तु रलो व्युपधादिति विकल्पे प्राप्ते नित्यार्थम् । तत्र विधिसम्भवे क्लिशेरनिटः क्त्वः कित्त्वविधानं नियमार्थं न भवति ॥ सन्नर्थमिति । तत्र चरितार्थत्वादनिटः क्त्वः कित्त्वविधानं नियमार्थं न भवति॥

(उद्योतः) भाष्ये विभाषितेड्ग्रहणमुपलक्षणमित्याशयेनाह—गुधेति ॥ ननु रुदविदेति सूत्रे स्वपिप्रच्छिग्रहणमनिटां नियामकं स्यादतो भाष्ये—रुदविदमुषग्रहिस्वपीति । तत्र सूत्रे स्वपिप्रच्छ्योर्ग्रहणमित्यर्थः ॥ तद्ध्वनयन्व्याचष्टे—तत्रेति । व्याख्यानात् वरतया न सम्बन्ध इति भावः । स्वपिप्रच्छ्योः क्त्वः कित्वविधानमनिटः क्त्वो नियमार्थं न भवतीत्यन्वयः ॥ ७ ॥

(७४ कित्वातिदेशसूत्रम् ॥ १ । २ । १ आ. ६ सू.)

८३ इको झल् ॥ १ । २ । ९ ॥

(योगविभागप्रयोजनाधिकरणम्)

(आक्षेपभाष्यम्)

किमर्थमिकः परस्य सनः कित्त्वमुच्यते? ।

(प्रदीपः) इको ॥ ९ ॥ किमर्थमिति । इको झल् हलन्ताच्चेत्येक एव योगः कर्तव्यः किमर्थो योगविभाग इति प्रश्नार्थः । वक्ष्यमाणश्चात्राभिप्रायः ॥

(उद्योतः) इको झल् ॥ ९ ॥ सूत्रं किमर्थमिति वक्तव्ये किमितीकः परस्येत्युक्तमत आह—इक इति । उत्तरार्थं सूत्रमावश्यकमिति भावः । अत एवेक्धातोर्न ग्रहणम् । उत्तरत्रार्थाधिकारानुरोधात् ॥

(५८५ समाधानवार्तिकम् ॥ १ ॥)

॥ * ॥ इकः कित्त्वं गुणो मा भूत् ॥ * ॥

(भाष्यम्) इकः कित्त्वं क्रियते गुणो मा भूदिति । चिचीषति । तुष्टूषति ॥

(समाधाननिराकरणभाष्यम्)

नैतदस्ति प्रयोजनम् ।

(५८६ निराकरणहेतुवार्तिकम् ॥ २ ॥)

॥ * ॥ दीर्घारम्भात् ॥ * ॥

(भाष्यम्) दीर्घत्वमत्र बाधकं भविष्यति ॥

(प्रदीपः) दीर्घत्वमिति । अज्झनगमां सनीति दीर्घत्वं नाप्राप्ते गुण आरभ्यमाणं तस्य बाधकमिति भावः ॥

(उद्योतः) ननु गुणस्य परत्वात्कथं दीर्घो बाधकोत आह—अज्झनेति । एवं चानवकाशत्वाद् दीर्घो गुणस्य बाधक इति भावः॥

(५८७ समाधानसाधकवार्तिकम् ॥ ३ ॥)

॥ * ॥ कृते भवेत् ॥ * ॥

(भाष्यम्) कृते खलु दीर्घत्वे गुणः प्राप्नोति ॥

(प्रदीपः) कृते भवेदिति । शास्त्रमावर्तमानं धर्मसाधनं जपादिवदिति भावः ॥

(उद्योतः) भाष्ये कृते भवेदिति । अनवकाशत्वेन बाधकस्य प्रवृत्त्युत्तरमुत्सर्गप्रवृत्तेरङ्गीकारादिति भावः ॥ शास्त्रं प्रवर्तमानमिति । एवं चावृत्त्यर्थं प्रवृत्त्या शास्त्रस्यानर्थक्याभावान्न बाध इति भावः ॥ शास्त्रमावर्तमानमिति क्वचित्पाठः तत्राप्ययमेवार्थः॥

(५८८ आक्षेपवार्तिकम् ॥ ४ ॥)

॥ * ॥ अनर्थकं तु ॥ * ॥

(भाष्यम्) अनर्थकमेवं सति दीर्घत्वं स्यात् ॥

(प्रदीपः) अनर्थकं त्विति । शास्त्रपूर्वकात्प्रयोगाद्धर्मो न तु शास्त्रप्रवृत्तिमात्रादिति भावः ॥

(भाष्यम्) नानर्थकम् ।

(५८९ आक्षेपसमाधानवार्तिकम् ॥ ५ ॥)

॥ * ॥ ह्रस्वार्थम् ॥ * ॥

(भाष्यम्) ह्रस्वानां दीर्घवचनसामर्थ्याद् गुणो न भविष्यति ॥

(प्रदीपः) **ह्रस्वार्थमिति**। ह्रस्वानामेव दीर्घविधानसामर्थ्याद् गुणो न स्यात्॥

(उद्द्योतः) ननु शास्त्रस्य साधारणत्वेन ह्रस्वविषये एव बाधो नान्यत्रेत्यत्र किं विनिगमकमत आह—**ह्रस्वानामेवेति**।

(आक्षेपशेषभाष्यम्)

भवेद् ह्रस्वानां दीर्घवचनसामर्थ्याद् गुणो न स्यात्॥

(उद्द्योतः) ह्रस्वार्थं दीर्घविधानं चेत्किं तत्राह—भाष्ये—**भवेदित्यादि**॥

(५९० आक्षेपवार्तिकम्॥ ६॥)

॥ * ॥ दीर्घाणां तु प्रसज्यते ॥ * ॥

(भाष्यम्) **दीर्घाणां तु खलु गुणः प्राप्नोति॥**

(प्रदीपः) दीर्घाणां तु प्रागेव ताद्रूप्याद्रूपविशेषसंपत्तिफलत्वाच्छास्त्रस्य दीर्घशास्त्राप्रवर्तनाद् गुणप्रसङ्गः॥

(आक्षेपबाधकभाष्यम्)

दीर्घाणामपि दीर्घवचनसामर्थ्याद् गुणो न भविष्यति॥

(प्रदीपः) **दीर्घाणामपीति**। गुणापाकरणार्थं दीर्घेष्वपि दीर्घशास्त्रं प्रवर्तत एवेत्यर्थः॥

(उद्द्योतः) **गुणापेति**। एवं न तन्निवृत्त्या रूपविशेषसम्पत्तिः फलमस्त्येवेत्यर्थः॥

(आक्षेपसाधकभाष्यम्)

न दीर्घाणां दीर्घाः प्राप्नुवन्ति॥ किं कारणम्?॥ नहि भुक्तवान् पुनर्भुङ्क्ते, कृतश्मश्रुश्च पुनः श्मश्रूणि कारयति॥

(प्रदीपः) **नहि भुक्तवानिति**। तृप्तिफलं भोजनं फले सम्पन्ने पुनर्न प्रवर्तते॥

(उद्द्योतः) नहीतिहिशब्दसूचितं हेतुमाह—**तृप्तीति**॥

(आक्षेपबाधकभाष्यम्)

ननु च पुनः प्रवृत्तिरपि दृष्टा—भुक्तवानपि पुनर्भुङ्क्ते, कृतश्मश्रुश्च पुनः श्मश्रूणि कारयति॥

(प्रदीपः) **ननु चेति**। तृप्तोपि पुनर्भुङ्क्त इत्यर्थः॥

(५९१ आक्षेपसाधकवार्तिकम्॥ ७॥)

॥ * ॥ सामर्थ्याद्धि पुनर्भाव्यम् ॥ * ॥

(भाष्यम्) **सामर्थ्याद्धि पुनः प्रवृत्तिर्भवति। भोजनविशेषाच्छिल्पविशेषाद्वा। दीर्घाणां पुनर्दीर्घत्ववचने न किंचित्प्रयोजनमस्ति। "अकृतकारि खल्वपि शास्त्रमग्निवत्"। तद्यथा—अग्निर्यददग्धं तद्दहति॥**

(प्रदीपः) **भाव्यमिति**। कर्तव्यं भोजनं तृप्तिविशेषार्थिभिरित्यर्थः॥ **न किं चिदिति**। नहि दीर्घाणां दीर्घतरः सम्पद्यत इत्यर्थः॥ **अग्निवदिति**। दग्धस्यायोग्यत्वाददाह इति भावः। इहाप्ययोग्यत्वाद्दीर्घेषु दीर्घशास्त्रेण न प्रवर्तितव्यमिति भावः॥

(उद्द्योतः) भाव्यमित्यस्य **कर्तव्यमिति** व्याख्या, शेषपूरणमन्यत्॥ **तृप्तिविशेषेति**। विजातीया विजातीया तृप्तिस्तत्तद्भोजनफलमिति भावः॥ भाष्ये—**भोजनविशेषादिति**। भोजनेति कर्मणि ल्युट्॥ शिल्पविशेषादिति पाठः॥ **नहीति**। तत्र तृप्तिविशेषवद् नात्र दीर्घविशेषः फलमिति भावः॥

(आक्षेपबाधकभाष्यम्)

दीर्घाणामपि दीर्घवचन एतत्प्रयोजनं गुणो मा भूदिति॥ "कृतकारि खल्वपि शास्त्रं पर्जन्यवत्"। तद्यथा—पर्जन्यो यावदूनं पूर्णं च सर्वमभिवर्षति॥

(प्रदीपः) **दीर्घाणामपीति**। ह्रस्वेष्वपूर्वदीर्घरूपसंपादनार्थं दीर्घशास्त्रं प्रवर्तते दीर्घेषु तु रूपप्रतिबन्धिगुणनिवर्तनेन स्वरूपप्रत्यापत्तये। यथा—**मोराजि समः क्वाविति** मकारस्य मकार इति भावः। ततश्च ह्रस्वानामिव दीर्घाणामपि **येन नाप्राप्तिन्यायेन** दीर्घेण गुणो बाध्यत एव॥

(उद्द्योतः) **ह्रस्वेष्विति**। लक्ष्यभेदादेकस्यापि विधिनियमरूपेण प्रवृत्तिरिति भावः॥ **येननाप्राप्तिन्यायेन**। अनवकाशत्वेन॥

(आक्षेपभाष्यम्)

यथैव तर्हि दीर्घत्ववचनसामर्थ्याद् गुणो न भवति। एवमृदित्त्वमपि न प्राप्नोति—चिकीर्षति जिहीर्षति॥

(प्रदीपः) **यथैवेति**। दीर्घारम्भादविकृतेनैव दीर्घेण स्थातव्यमिति भावः।

(उद्द्योतः) [भाष्ये] **ऋदित्त्वम्**। **ऋत इद्धातोरितीत्त्वम्**।

(५९२ समाधानवार्तिकम्॥ ८॥)

॥ * ॥ ऋदित्त्वं दीर्घसंश्रयम् ॥ * ॥

(भाष्यम्) **नाकृते दीर्घे ऋदित्त्वं प्राप्नोति॥ किं कारणम्?॥ ऋत इत्युच्यते॥**

(प्रदीपः) **ऋदित्त्वमिति**। यद्यन्तरेण दीर्घविधानं प्राप्नुयादृदित्त्वं तदा तद्दीर्घेण बाध्येत यतस्तु दीर्घाश्रयमेव ऋदित्त्वं तदा तदेव फलं दीर्घस्य संजातमिति ऋदित्त्वं प्रवर्तिष्यते। तथा चोच्यते—'यं विधिं प्रत्युपदेशोऽनर्थकः स विधिर्बाध्यते यस्य तु विधेर्निमित्तमेव नासौ बाध्यते' इति।

(समाधानबाधकभाष्यम्)

भवेद् ह्रस्वानां नाकृते दीर्घे ऋदित्त्वं स्याद्, दीर्घाणां तु खल्वकृतेपि दीर्घत्वे ऋदित्त्वं प्राप्नोति॥

(५९३ समाधानसाधकवार्तिकम् ॥ ९ ॥)

॥ * ॥ दीर्घाणां नाकृते दीर्घे ॥ * ॥

(भाष्यम्) दीर्घाणामपि नाकृते दीर्घत्वे ऋदित्त्वं प्राप्नोति। यदा दीर्घत्वेन गुणो बाधितः तत उत्तरकालमृदित्त्वं भवति॥

(प्रदीपः) दीर्घाणामिति॥इत्त्वोत्त्वाभ्यां गुणवृद्धी भवतो विप्रतिषेधेनेति गुणप्रसङ्गादिति भावः॥

(५९४ समाधानवार्तिकम् ॥ १०)

॥ * ॥ णिलोपस्तु प्रयोजनम् ॥ * ॥

(भाष्यम्) इदं तर्हि प्रयोजनम्। णिलोपो यथा स्यात्—ज्ञीप्सति॥

(प्रदीपः) ज्ञीप्सतीति। असति कित्त्वे गुणवण्णिलोपस्यापि विशेषाभावाद्दीर्घत्वं बाधकं स्यादित्यर्थः॥

(उद्योतः) णिलोपस्य किंनिमित्तत्वाभावात्कथं णिलोपस्तत्र प्रयोजनमत आह—असतीति॥ णिलोपस्यापीति। बाध्यसामान्यचिन्तायामिति भावः॥

(समाधानबाधकभाष्यम्)

कास्ताः क्व निपतिताः क्व कित्त्वं क्व णिलोपः। को वा ऽभिसंबन्धः—यत्सति कित्त्वे णिलोपः स्याद्, असति कित्त्वे न स्यात्?॥

(प्रदीपः) कास्ता इति। यथान्यत्र क्षिप्तानां शरादीनामन्यत्र निपातो ऽसंभाव्यः। एवं कित्त्वणिलोपयोरपि संबन्धो न संभाव्यत इत्यर्थः॥

(समाधानसाधकभाष्यम्)

एषोभिसम्बन्धः—यत्सति कित्त्वे सावकाशं दीर्घत्वं परत्वाण्णिलोपो बाधते। असति पुनः कित्त्वेनवकाशं दीर्घत्वं यथैव गुणं बाधते, एवं णिलोपमपि बाधेत। तत्र णिलोपस्यावकाशः—कारणा हारणा। दीर्घत्वस्यावकाशः—चिचीषति तुष्टूषति। इहोभयं प्राप्नोति—ज्ञीप्सति। परत्वाण्णिलोपः॥

(प्रदीपः) एषोभिसंबन्ध इति। ज्ञीप्सतीति णेर्गुणलोपदीर्घत्वानि प्राप्नुवन्ति। तत्रासति कित्त्वे ऽनवकाशत्वाद्विशेषाभावाच्च गुणवण्णिलोपस्यापि दीर्घत्वं बाधकं स्यात्॥ अथ वा पुरस्तादपवादा अनन्तरान्विधीन्बाधन्ते नोत्तरानिति णिलोपस्यैव बाधकं तत्स्यात्, गुणस्तु स्यादेव। सति तु कित्त्वे तेनैव गुणो बाधित इति चिचीषतीत्यादौ लब्धावकाशं दीर्घत्वं परत्वाण्णिलोपेन बाध्यते॥ नन्वसत्यपि कित्त्वे येन नाप्राप्त इति न्यायेन गुणस्यैव बाधकं दीर्घत्वं भविष्यति न णिलोपस्य, गुणबाधनेन च सावकाशं दीर्घत्वं परत्वाण्णिलोपेन बाधिष्यत इति नार्थः कित्त्वेन॥ नैतदस्ति। यदा बाध्यं भेदेनापेक्ष्यते इदं सर्वत्र प्राप्तमिदं तु क्वचिदेवेति, तदायं न्यायः। यदा तु बाध्यमात्रमपेक्ष्यते विध्यन्तरेणाव्याप्तो विषयो न कश्चिदस्तीति तदा सर्वस्यैव बाधया भवितव्यम्॥

(उद्योतः) ज्ञीप्सतीति। ज्ञपेश्वुरादिणिचि मितां ह्रस्वत्वे सनीवन्तेतीडभावे आप्ज्ञपीति ईत्वेऽभ्यासलोपे रूपम्॥ विशेषचिन्तायामपि दोष इत्याह—अथवेति॥ ननु येननाप्राप्तिन्यायेन यत्रोभयापवादतासम्भावना तत्रैषां व्यवस्थापकत्वं, नच तथा प्रकृते। यथैलेधतीत्यादौ पररूपत्वावच्छिन्ने बाध्ये 'किंशास्त्रविहितस्य'इत्याकाङ्क्षायां मध्येपवादाः पुरस्तादिति न्यायविषयः। येनेत्यस्य यद्धर्मावच्छिन्नकार्येणेत्यर्थः। येन लक्षणेनेत्यर्थे तु नास्य विषयः, नापि कार्यभेदे यच्छब्दपरामर्श्यानुगमकरूपाभावादिति चेन्न। व्यक्तिपक्षे 'किमिदं गुणबाधकतया सर्वविषयम्, उत णिलोपबाधकतया णिविषयम्' इति सन्देहे व्यवस्थाया अवश्यापेक्षितत्वेन शास्त्रप्रवृत्तिः सुप्रपादेत्यभिमानात्॥ वस्तुतस्त्वेवं सति णिगमेत्येव वदेदिति बाध्यसामान्यचिन्तापक्षमाश्रित्यैव भाष्यव्याख्योचितेति दिक्। तद् ध्वनयन् शङ्कते—नन्वसत्यपीति। येनेत्यस्य येन कार्येणेत्यर्थ इति भावः॥ नैतदिति। येनेत्यस्य स्वेतरेणेत्यर्थकतया यदा बाध्यसामान्यचिन्तापरत्वमस्य न्यायस्य तदायं ग्रन्थ इति भावः॥ भाष्ये कित्त्वारम्भे न दोष इत्याह—तत्र णिलोपस्येत्यादिना॥

(समाधानबाधकभाष्यम्)

असत्यपि कित्त्वे सावकाशं दीर्घत्वम्॥ कोवकाशः?॥ इस्भावः—निमित्सति प्रमित्सति। मीनातिमिनोत्योर्दीर्घत्वे कृते मीग्रहणेन ग्रहणं यथा स्यात्॥

(प्रदीपः) असत्यपीति। मीनातिमिनोत्योः सन्यनवकाशत्वाद्गुणं बाधित्वा दीर्घः प्रवर्तते। ततो मीग्रहणेन ग्रहणादिस्भावेन प्रतिपदविहितेन गुणो बाध्यते। कृते चेस्भावे हलन्ताच्चेति कित्त्वाल्लघूपधगुणाभावः।तत्र सामान्यग्रहणे चरितार्थत्वाद्दीर्घविधानस्य ज्ञीप्सतीतिपरत्वाण्णिलोपो भविष्यतीति नार्थः कित्त्वेन॥ ननु लाक्षणिकत्वान्मिनोतेर्मीरूपस्य मीग्रहणेन ग्रहणं न प्राप्नोति॥ नैष दोषः। यत्र लक्षणाभिनिर्वृत्तत्वेन शब्दरूपमपेक्ष्यते तत्र लक्षणप्रतिपदोक्तयोरिति परिभाषोपस्थानं न तु यत्र प्रयोगरूपाश्रयणं तत्र॥ नन्वेवमसत्यपि मीग्रहणेन ग्रहणे मीनातीत्यादिनाऽऽत्वे कृते गामादाग्रहणेष्वविशेष इति माग्रहणेन ग्रहणादिस् भविष्यतीति सामान्यग्रहणमपि दीर्घस्य प्रयोजनं नोपपद्यते॥ एवं तर्हि दोषान्तराभिधानेनास्य पूर्वपक्षस्य निराकरणाद्भाष्यकारेण नैतत्सुष्ठु निरूपितम्॥

(उद्योतः) प्रतिपदविहितेनेति। मीविषयेणाचरितार्थेनेत्यर्थः। एवं च तत्र सूत्रे मीग्रहणेन मिनोतेरपि ग्रहणं दीर्घस्य प्रयोजनमिति भावः॥ सावकाशमिति भाष्यस्य सार्थकमित्यर्थः॥ परत्वादिति। यद्यपि प्रमित्सतीत्यत्र अपवादत्वाद् दीर्घेण गुणस्येव ज्ञीप्सतीत्यत्र बाध्यसामान्यचिन्तायां णिलोपस्यापि बाधेन भाव्यं,

तथापि दीर्घसमानकालिकस्य णिलोपस्य गुणस्येव बाधेपि दीर्घे कृते स्थानिवत्त्वेन प्राप्तणिलोपः स्यादेवं । न च दीर्घविधानसामर्थ्यम् । इग्भावे सामान्यग्रहणसम्पादनेन कृतार्थत्वात् । एवं च परत्वादित्यस्य दीर्घोत्तरकालं प्राप्तत्वादित्यर्थः ॥ अष्टावसरन्यायस्तु शास्त्रे नास्त्येवेति भावः ॥ यत्र लक्षणेति । यथा 'विभाषा दिक्समासे' 'तृतीयासमास'इत्यादौ । तत्र हि समासशब्दस्य संज्ञात्वेन तज्ज्ञानाय लक्षणपर्यालोचनमित्यर्थः ॥ प्रयोगरूपेति । तच्च मीयतइत्यादिप्रयोगनिष्ठम् । एवं हि गामादाग्रहणेष्वविशेष इत्यादेरसङ्गतिः स्यादिति मानाद्यचर्योद् मीशब्दांशेपि सा न प्रवर्त्तेत इत्येव समाधातुं युक्तम् ॥ तद् ध्वनयन्नाह—नन्वेवमसत्यपीति । कित्त्वाभावे गुणविषयत्वेनात्वस्य सुलभत्वादिति भावः ॥ एवं च मीग्रहणमपि व्यर्थमिति तात्पर्यम् ॥ भाष्ये मीनातिमिनोत्योर्दीर्घत्वे कृत इत्यत्र पर्जन्यवल्लक्षणप्रवृत्तिमाश्रित्य मीनातिनिर्देशः ॥

(समाधानसाधकभाष्यम्)

यथैव तर्ह्यसति कित्त्वे सावकाशं दीर्घत्वं परत्वाण्णिलोपो बाधते, एवं गुणोपि बाधेत । तस्मात्कित्त्वं वक्तव्यम् ॥

इकः कित्त्वं गुणो मा भूद् दीर्घारम्भात्कृते भवेत् ।
अनर्थकं तु ह्रस्वार्थं दीर्घाणां तु प्रसज्यते ॥ १ ॥
सामर्थ्याद्धि पुनर्भाव्यमृदित्त्वं दीर्घसंश्रयम् ।
दीर्घाणां नाकृते दीर्घे णिलोपस्तु प्रयोजनम् ॥२॥
इको झल् ॥ ९ ॥

(प्रदीपः) तदेव दोषान्तरमाह—यथैवेति । सामान्यग्रहणे उपयुक्तत्वाद्दीर्घत्वस्य नास्त्यनवकाशत्वमिति द्वाभ्यामपि गुणणिलोपाभ्यां दीर्घत्वं बाध्यत इति कर्तव्यं कित्त्वम् । न च दीर्घविधानस्य 'कुङ् शब्दे' इति धातुरवकाशः चुकूषत इति । यस्मात्कुङ् शब्द इति पाठस्तत्र कुटादित्वान्ङित्त्वे सति गुणाभावाद्दीर्घस्य श्रवणं सिद्धम् । वेदलोकयोश्चाकूतशब्दस्य प्रयोगो दृश्यते । गुधुवाववकाशाविति चेद् उहनिगमामिति ब्रूयात् किं प्रत्याहारेण ॥ ९ ॥

(उद्द्योतः) [भाष्ये] परत्वादित्यस्योत्तरकालप्राप्तत्वादित्येवार्थः । यथा दीर्घोत्तरं स्थानिवत्त्वेन णिलोपो भवति, एवं तत्प्रवृत्त्युत्तरमेव गुणोपि स्याद् । दीर्घत्वं तु सामान्यग्रहणाविघातार्थं स्याद् इति भावः ॥ नास्त्यनवकाशत्वमिति । नास्त्यनर्थकत्वमित्यर्थः ॥ दीर्घत्वं बाध्यत इति । प्रवृत्तमपि निवर्त्यते इत्यर्थः ॥ धातुरवकाश इति । तस्य च कुटादित्वप्रयुक्तङित्त्वेन गुणनिषेधाद्दीर्घश्चरितार्थ इति भावः ॥ एवं चेत्भावे एवावकाशोक्तिर्भाष्योक्ताऽसङ्गतेति तात्पर्यम् ॥ उहनेति । न चाजादेशगमेरित्यर्थलाभार्थमज्ग्रहणम् । इणिसाहचर्येण लुग्विकरणस्थानिकादेशगमेरेव ग्रहणेनादोषात् । एवं च कुङः सत्त्वेपि न क्षतिरिति बोध्यम् ॥ कुगुधुभ्यः कुटादिभ्यश्च सनोऽनभिधानमित्यन्ये ॥ ९ ॥

(७५ कित्त्वातिदेशसूत्रम् ॥ २ । २ । १ आ. ७ मं सू. ॥)

८४ हलन्ताच्च ॥ १ । २ । १० ॥

सौत्रनिर्देशोपपादनाधिकरणम् ।

(आक्षेपभाष्यम्)

अयुक्तोयं निर्देशः । कथं हि इको नाम हलन्तः स्यादन्यस्यान्यः ? ।

(प्रदीपः) हलन्ताच्च॥१०॥अयुक्त इति । अन्तशब्दमवयववचनं मत्वा पर्यनुयुङ्क्ते ॥ अन्यस्यान्य इति । अत्यन्तभेदमनेन दर्शयति । अवयवावयविनोस्तु भेदविवक्षापि भवति—तन्तूनां पट इति । अभेदविवक्षापि—पटीभवन्ति तन्तव इति ॥

(उद्द्योतः) हलन्ताच्च ॥ १० ॥ अन्तशब्दस्य समीपवचनत्वान्नार्थानुपपत्तिरिहत्यसमीपादिकः पर इत्यर्थः, ततः परत्वं च सामर्थ्यादेकवर्णव्यवहितं आश्रमतआह—अवयवेति ॥ भेद एवावयवावयविभावादाह—अत्यन्तभेदमिति । भेदाभेद एवावयवावयविभाव इत्यर्थः ॥ भाष्ये इष्टार्थबोधाक्षमत्वेन निर्देशस्यायुक्तत्वम् ॥ इको नामेति । इगन्तस्य धातोरित्यर्थः ॥ हलन्तः स्यादिति । हलन्तावयवः स्यादित्यर्थः ॥ अन्यस्य । इगन्तस्य ॥ अन्यः । हल् कथमन्तो भविष्यतीति शेषः । इक्पदेन वर्णमात्रग्रहेपि द्वयोर्वर्णयोः परस्परमवयवावयविभावो विरुद्ध इति भावः ॥

(प्रत्याक्षेपभाष्यम्)

कथं तर्हि निर्देशः कर्तव्यः ? ।

(प्रत्याक्षेपसमाधानभाष्यम्)

'इग्वतो हलः' इति ॥

(प्रदीपः) **इग्वतो हल इति । हलन्तादित्यर्थः ॥**

(उद्द्योतः) नन्वानन्तर्यादिषु बहुव्रीहेरिव मत्वर्थीयस्याप्यभावा द्वर्णयोरवयवावयविभावाभावाच्च 'इग्वतो हल' इत्ययुक्तमतआह—इकन्तादिति । सनाक्षिप्तस्य धातोः शब्दस्य रूपस्य वा हला विशेषणात्तदन्तविधिरित्यर्थः ॥ वस्तुत इग्वतो इकन्तादिति न्यासकरणे तात्पर्यम्, अत एवेगुपधाद्धलन्तादिति वक्ष्यति ॥

(आक्षेपबाधकभाष्यम्)

यद्येवं 'यियक्षति' अत्रापि प्राप्नोति ॥

(प्रदीपः) **यियक्षतीति । अत्र संप्रसारणप्रसङ्गः ॥**

(न्यासान्तरप्रदर्शनभाष्यम्)

एवं तर्हि 'इगुपधाद्धलन्ताद्'इति वक्ष्यामि ॥

(न्यासान्तरदूषणभाष्यम्)

एवमपि दम्भेर्न प्राप्नोति ॥ सूत्रं च भिद्यते ॥

(सिद्धान्तिसमाधानभाष्यम्)

यथान्यासमेवास्तु ॥

(आक्षेपसारणभाष्यम्)

ननु चोक्तम्—'अयुक्तोयं निर्देशः' इति ॥

(समाधानभाष्यम्)

नायुक्तः । अयमन्तशब्दोऽस्त्येवावयववाची । तद्यथा—'वस्त्रान्तः, वसनान्तः' इति, वस्त्रावयवो वसनावयव इति गम्यते । अस्ति सामीप्ये वर्तते। तद्यथा—'उदकान्तं गतः' इति, उदकस्य समीपं गत इति गम्यते । तद्यः सामीप्ये वर्तते, तस्येदं ग्रहणम् ॥

(प्रदीपः) **तद्यः सामीप्य इति** । एवं च हल् चासावन्तश्चेति कर्मधारयः । निपातनाच्च विशेषणस्य परनिपातः ॥

(उद्द्योतः) **कर्मधारय इति** । स्वपदार्थप्रधानत्वेनान्तरङ्गत्वादयमेवोचित इति भावः ॥ पूर्वनिपाताभावं परिहरति—**निपातनादिति** । बहुव्रीहिपक्षेप्येतदावश्यकमिति भावः ॥

(आक्षेपभाष्यम्)

एवमपि दम्भेर्न सिध्यति। यो ह्यत्रेक्समीपो हल्. न तस्मादुत्तरः सन्,यस्मादुत्तरः सन्. नासाविक्समीपे ॥

(प्रदीपः) **एवमपीति** । व्यक्तिनिर्देश इति भावः। असति च कित्त्वे नलोपो न स्यात् ॥

(उद्द्योतः) **दम्भ** इत्येतीस्वेऽलघूपधत्वाद् गुणाप्रसक्तेः किं कित्त्वेनेत्याशङ्क्याह—**असतीति** ॥ **नलोप इति** । अनिदितामित्यनेन ॥

(समाधानभाष्यम्)

एवं तर्हि—

(५९५ सिद्धान्तसमाधानवार्तिकम् ॥ १ ॥)

॥ * ॥ दम्भेर्हल्ग्रहणस्य जातिवाचकत्वात्सिद्धम् ॥ * ॥

(भाष्यम्) **हल्जातिर्निर्दिश्यते—इक उत्तरा या हल्जातिरिति ॥ हलन्ताच्च ॥ १० ॥**

(प्रदीपः) **दम्भेरिति** । 'वर्णग्रहणे जातिग्रहणम्' इति **निपात एकाजनाङ्क्लित्यत्रैकग्रहणेन** ज्ञापितत्वात् । न चात्र व्यक्तिगतमेकत्वम्, अपि तु जातेः स्वगतम्। तत्र यदा तावद्व्यक्तिव्यतिरिक्ता जातिस्तस्याश्च व्यक्तिद्वारकाः सामीप्यादयो धर्मास्तदा तस्या एकत्वादिक्समीपत्वं सनश्च परत्वं तदपेक्षमस्तीति सिद्धं धिप्सतीति कित्त्वम् । हकारादिषु चाभिन्नप्रत्ययाभिधानाद्धल्त्वजातेः सद्भावः । यदापि 'त्यक्तभेदा व्यक्तय एव जातिः' इति पक्षस्तदा भेदव्युदासादभेदाश्रयणादिष्टसिद्धिः ॥ १० ॥

(उद्द्योतः) **एकत्वं** हलन्तादित्येकवचनोपात्तम् ॥ **जातेः स्वगतमिति**।तस्याः प्राधान्येन विवक्षितत्वाद् एको व्रीहिः सम्पन्नः, इतिवदिति भावः॥ ननु जातिनिर्देशे पौर्वापर्य कथमत आह—**यदा तावदिति** । यद्यप्येकैकव्यक्तिव्यङ्ग्या जातिस्तथापि ज्ञापकेन विजातीयव्यवधाने यत्किञ्चिद्व्यक्तिद्वारकं सामीप्यं यत्किञ्चिद्व्यक्तिद्वारकं च ततः परत्वं श्रीयत इति भावः ॥ **व्यक्तिद्वारका इति** । विशेषणीभूतव्यक्तिद्वारका इत्यर्थः ॥ **तदपेक्षं** व्यक्तिद्वारकं जात्यपेक्षम् ॥ **अभिन्नप्रत्ययः** । हलित्येकाकारः प्रत्ययः । अनेन हल्त्वजातौ प्रमाणं संज्ञाशब्दाश्च जातिशब्दा एवेति दर्शितम् ॥ **यदापीति** । तदा तु साक्षादेव परत्वादीति भावः । परस्परभेदधर्मपरित्यागेन व्यक्तिमात्रविवक्षायां सा एकैवेति तात्पर्यं तदाह—**भेदव्युदासादभेदाश्रयणादिति** । अयं पक्षो मञ्जूषायामुपपादितो विस्तरेणास्माभिः शक्तिवादान्ते ॥ परे तु **हल्जातिरित्यस्य** तज्जात्याश्रयहल्समुदाय इत्यर्थस्तस्य च साक्षादेव सामीप्यं ततः परत्वं चोपपद्यते । तदुक्तं भाष्ये—**इक उत्तरा या हल्जातिरिति** । अत एवार्धधातुक इति सूत्रे वक्ष्यति—जातेः पौर्वापर्यासम्भवाद्विषयसप्तमी विज्ञास्यत इतीत्याहुः ॥ १० ॥

(७६ किद्वातिदेशसूत्रम् ॥ १ । २ । १ आ. ८ सू.)

८५ लिङ्सिचावात्मनेपदेषु ॥ १।२।११ ॥

(आत्मनेपदपदान्वयाधिकरणम्)

(आक्षेपभाष्यम्)

कथमिदं विज्ञायते—आत्मनेपदं यौ लिङ्सिचाविति । आहोस्विदात्मनेपदेषु परतो यौ लिङ्सिचाविति ? ॥

(प्रदीपः) **लिङ्सि ॥ ११ ॥ कथमिति** । आत्मनेपदेष्विति सकृच्छ्रुतस्य अर्थद्वयं न लभ्यते। तत्र यदि निर्धारणसप्तमी तदा तुल्यजातीयस्य निर्धारणाल्लिङेव विशेषितः स्याद्, लिङ्शब्देन लिङादेशग्रहणात् । अथ परसप्तमी तदा सिजेव विशेष्यते, न लिङ् । सीयुडादिसमुदायो लिङ्शब्देन गृह्यते इति तस्यात्मनेपदपरत्वाभावः । नचानयोर्भिन्नयोरर्थयोः सहविवक्षा संभवतीत्येकशेषस्याप्रयोगः ॥

(उद्द्योतः) **लिङ्सिचौ ॥ ११ ॥ सकृच्छ्रुतस्यार्थद्वयमिति** । कालभेदेनार्थद्वयबोधजनकत्वमित्यर्थः ॥ नन्वात्मनेपदं यौ लिङ्सिचाविति व्याख्याने सप्तम्यनुपपन्नेत्यत आह—**निर्धारणे इति** । निर्धारणं च सजातीययोरिति तदभेदलाभः ॥ भाष्ये—**सिजविशेषित इति** । सम्भवव्यभिचारयोरभावादिति भावः ॥ ननु लिङ आत्मनेपदत्वाभावोत आह—**लिङ्शब्देनेति** ॥ ननु सम्भावितात्मनेपदपरत्वौ सुट्सीयुटावेव लिङ्ग्रहणेन ग्रहीष्येते इत्यत आह—**सीयुडादीति** ॥ नन्वस्तूभयोरेकशेपनिर्देशोत आह—**न चेति** । अनेन शास्त्रीयैकशेषो वारितः ॥ **अप्रयोग इति** । कृतैकशेपस्य सूत्रेऽप्रयोग इत्यर्थः ॥

(फलभेदजिज्ञासाभाष्यम्)

किं चातः ? ।

(अनुपपत्तिभाष्यम्)

यदि विज्ञायते-आत्मनेपदं यौ लिङ्सिचाविति।

लिङ् विशेषितः, सिजविशेषितः ॥ अथ विज्ञायते— आत्मनेपदेषु परतो यौ लिङ्सिचाविति । सिज्विशेषितः, लिङविशेषितः ॥

(अनुपपत्तिपरिहारभाष्यम्)

यथेच्छसि तथास्तु ॥

(प्रथमपक्षाभ्युपगमभाष्यम्)

अस्तु तावद्—आत्मनेपदं यौ लिङ्सिचौ' इति॥

(आक्षेपस्मारणभाष्यम्)

ननु चोक्तम्—'लिङ् विशेषितः, सिजविशेषितः' इति ॥

(आक्षेपनिरसनभाष्यम्)

सिच विशेषितः ॥ कथम्! ॥ आत्मनेपदं सिज्नास्तीति कृत्वा आत्मनेपदपरे सिचि कार्यं विज्ञास्यते ॥

(प्रदीपः) सिच विशेषित इति । आत्मनेपदपरत्वादुपचारात्सिजेवात्मनेपदमुच्यते गौणमुख्यार्थयोरात्मनेपदशब्दयोः साकूप्यमात्रप्रतिबद्ध एकशेषः करिष्यत इति भावः ॥

(उद्द्योतः) निर्धारणविभक्त्यन्तत्वे सिज्विशेषणत्वासम्भवादाह—आत्मनेपदेति ॥ ननु सरूपाणामेवैकशेषस्तत्कथमर्थद्वयबोधकत्वमत आह—साकूप्यमात्रेति । अर्थभेदेपीत्यर्थः । अक्षा इतिवदिति भावः । सौत्र एकशेष इति बोध्यम् ॥

(द्वितीयपक्षाभ्युपगमभाष्यम्)

अथ वा पुनरस्तु—आत्मनेपदेषु परतो यौ लिङ्सिचौ—इति ॥

(आक्षेपस्मारणभाष्यम्)

ननु चोक्तम्—सिज्विशेषितो लिङविशेषितः— इति ॥

(आक्षेपनिरसनभाष्यम्)

लिङ् च विशेषितः ॥ कथम्? ॥ आत्मनेपदेषु परतो लिङ् नास्तीति कृत्वाऽऽत्मनेपदे लिङि कार्यं विज्ञास्यते ॥

(प्रदीपः) आत्मनेपदे लिङीति । अवयवगतं पौर्वापर्यं समुदाय आश्रयिष्यत इति भावः। अथ वा तन्त्रेण शब्दद्वयोच्चारणादर्थद्वयं लभ्यते ॥

(उद्द्योतः) समुदाये इति । व्यपदेशिवद्भावेनेत्यर्थः ॥ अथवेति । तन्त्रं स्वसहविवक्षायामपि विद्वन्मानसराजहंसेतिवदिति भावः ॥ ११ ॥

(आक्षेपवैयर्थ्यभाष्यम्)

नैव वा पुनरर्थो लिङ्विशेषणेनात्मनेपदग्रहणेन ॥ किं कारणम्? ॥ झलिति वर्तते । आत्मनेपदेषु चैव लिङ् झलादिः, न परस्मैपदेषु । तदेतत्सिज्विशेषणमात्मनेपदग्रहणम् ॥

(प्रदीपः) नैव वेति । संभवव्यभिचाराभ्यां सिजेव विशेष्यते न लिङित्यर्थः ॥ ११ ॥

(आक्षेपभाष्यम्)

अथ सिज्विशेषणे आत्मनेपदग्रहणे सति किं प्रयोजनम्? ।

(प्रयोजनभाष्यम्)

इह मा भूत्—अपाक्षीत् । अवाप्सीत् ॥

(प्रयोजनबाधकभाष्यम्)

नैतदस्ति । इक इति वर्तते ॥

(प्रयोजनान्तरभाष्यम्)

एवमपि—अचैषीत् अनैषीत्, अत्रापि प्राप्नोति ॥

(प्रयोजनान्तरनिरसनभाष्यम्)

एतदपि नास्ति प्रयोजनम् । हलन्ताविति वर्तते॥

(प्रयोजनान्तरभाष्यम्)

एवमपि अकोषीद्मोषीदत्रापि प्राप्नोति ॥

(प्रयोजनान्तरनिरसनभाष्यम्)

नैतदस्ति । झलिति वर्तते ॥

(प्रयोजनान्तरभाष्यम्)

एवमपि—अभैत्सीत् अच्छैत्सीत् अत्रापि प्राप्नोति॥

(प्रयोजनान्तरनिरसनभाष्यम्)

नैतदस्ति । इग्लक्षणयोर्गुणवृद्ध्योः प्रतिषेधः । न चैषेग्लक्षणा वृद्धिः ॥

(प्रयोजनभाष्यम्)

इदं तर्हि प्रयोजनम्—इह मा भूत्—अस्राक्षीदद्राक्षीदिति ॥ किं च स्यात्? ॥ अकिल्लक्षणोऽमागमो न स्यात् ॥ लिङ्सिचावात्मनेपदेषु ॥११॥

(७७ कित्त्वातिदेशसूत्रम् । १ । २ । १ आ. ९. सू.)

९१ स्थाघ्वोरिच्च ॥ १ । २ । १७ ॥

(तपरनिर्देशप्रयोजनाधिकरणम्)

(५९६ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ इच्च कस्य तकारेत्त्वम् ॥ * ॥

(भाष्यम्) कस्य हेतोरिकारस्तपरः क्रियते ॥

(प्रदीपः) स्थाघ्वोरिच्च ॥१७॥ इच्च कस्येति । कथं पुनरत्र षष्ठी । यावता हेतुशब्दः श्लोके न प्रयुक्त इति हेतुतृतीयया भाव्यम् ॥ नैष दोषः । हेतुरूपताया अविवक्षणात् । संबन्धिरूपेण विवक्षितत्वाद् ॥ यथा 'मदीयाः पुत्राः' इति शैषिकः

प्रत्ययः तदुत्पत्तिकाले अपत्यरूपत्वस्याविवक्षणात् ॥ तकार इत् तकारेत् तस्य भावस्तकारेत्त्वं किमर्थं क्रियते ॥

(उद्द्योतः) स्याद्ध्वो ॥१७॥ **न प्रयुक्त** इति । एवं च षष्ठी **हेतुप्रयोग**इत्यस्याप्राप्तिरिति भावः ॥ **अपत्यरूपत्वस्येति** । तत्त्वेन विवक्षायां तु छो न स्यात्किंच स्यादिति भावः ॥ वस्तुत उक्तादन्य एवेदन्त्वंनद ।दार्थः, शेषाधिकारात् । एवं चेदंत्वेनाप्यपत्यबोधे शैषिको न साधुरिति **तस्येद**मिति सूत्रे **तस्यापत्य**मिति सूत्रे च निरूपयिष्याम इति चिन्त्यमिदम् । स च सम्बन्धो हेतुहेतुमद्भावे पर्यवस्यतीति भाष्ये **हेतो**रिति प्रयुक्तम् । हेतुशब्देन चात्र फलम् । इत्संज्ञकतकारः किं मुखसुखार्थं उत **तपरसूत्रप्रवृत्त्यर्थं** इति विचारतात्पर्यम् ॥ **तकार इदिति** । यस्येति शेषः, बहुव्रीहेरयं त्वः । इच्चेत्यत्रेत्संज्ञकतकारवत्त्वं किमर्थमिति भाष्यार्थः । मुखसुखार्थोपि तदर्थत्वेन वर्णोच्चारणस्य सार्थक्यादित्संज्ञां लभत इति भाष्यमतम् ॥

(५९७ समाधानवार्तिकम् ॥ २ ॥)

॥ * ॥ दीर्घो मा भूत् ॥ * ॥

(भाष्यम्) **दीर्घो मा भूदिति ॥**

(प्रदीपः) **दीर्घो मा भूदिति** । आन्तरतम्यात्प्राप्नोतीति भावः । **भाव्यमानोऽण्सवर्णान्न गृह्णाती**त्येष तु परिहारोऽनित्यत्वान्नोक्तः । क्वचिद्भाव्यमानेनापि सवर्णग्रहणात् । यथा ऽमूभ्यामित्यादावूकारो दीर्घस्य भवति । परिहारान्तराभिधानाद्वा ॥

(उद्द्योतः) ननु श्रुतत्वाद् ह्रस्व एव भविष्यतीत्यत आह—**आन्तरतम्यादिति** ॥

(५९८ समाधानबाधकवार्तिकम् ॥ ३ ॥)

॥ * ॥ कृतेपि सः ॥ * ॥

(भाष्यम्) **अन्तरेणाप्यारम्भं सिद्धोऽत्र दीर्घः "घुमास्थागापाजहातिसां हलि" इति ॥**

(प्रदीपः) **अन्तरेणापीति** ॥ इकारविधानेन विनापीत्यर्थः । किन्त्वं तु कर्तव्यमेव । तेन विना ईत्वस्य प्राप्त्यभावात् ॥

(उद्द्योतः) सूत्रारम्भं विनेत्यर्थः किं न स्यादत आह—**किन्त्वं त्विति** । तदर्थं सूत्रमावश्यकमिति भावः । ईत्वस्येति छेदः ॥

(५९९ प्रयोजनान्तरवार्तिकम् ॥ ४ ॥)

॥ * ॥ अनन्तरे प्लुतो मा भूत् ॥ * ॥

(भाष्यम्) **इदं तर्हि प्रयोजनम्—अनन्तरे प्लुतो मा भूदिति । कुतो नु खल्वेतत्—अनन्तरार्थ आरम्भे ह्रस्वो भविष्यति, न पुनः प्लुत इति ? ॥**

(प्रदीपः) **अनन्तर इति** । असदृश आदेशे क्रियमाण इत्यर्थः ॥

(उद्द्योतः) **असदृश इति** । सामर्थ्यादसदृशे इत्यर्थः । अव्यवहितपरोऽनन्तरशब्दो नेति भावः ॥

(६०० प्रयोजनान्तरनिराकरणवार्तिकम् ॥ ५ ॥)

॥ * ॥ प्लुतश्च विषये स्मृतः ॥ * ॥

(भाष्यम्) **विषये प्लुत उच्यते । यदा च स विषयो, भवितव्यमेव तदा प्लुतेन ॥**

इच्च कस्य तकारेत्त्वं दीर्घो मा भूदृतेपि सः ॥
अनन्तरे प्लुतो मा भूत् प्लुतश्च विषये स्मृतः ॥ १ ॥

स्याद्ध्वोरिच्च ॥ १७ ॥

(प्रदीपः) **प्लुतश्च विषय इति** । अनेन तपरत्वं प्रत्याख्यायते । यद्यनेन प्लुतो विधीयेत तदा यत्रापि विषये **ऽनन्त्यस्यापि प्रश्नाख्यानयोरि**त्यादिना प्लुतो विहितस्तत्राप्यनेन विधीयेत अस्मिन्कर्तव्ये **पूर्वत्रासिद्ध**मित्याष्टमिकस्य प्लुतस्यासिद्धत्वात्ततश्च पक्षेनुवाददोषः प्राप्नोतीति ह्रस्व एव भविष्यति ॥ अन्ये तु तपरत्वमनेन समर्थितमिति व्याचक्षते । अनन्तरेप्यादेशे श्रूयमाणे दीर्घ एव स्यात् ॥ ननु सिद्ध एव दीर्घ इत्युक्तं सिद्धस्यापि पुनर्विधानं प्लुतनिवृत्त्यर्थं स्याद् । माभूत् प्लुत इति चेत् । तत्र । **प्लुतश्च विषये स्मृत इति** । स चासति तपरत्वे न प्राप्नोतीति दीर्घनिवृत्त्यर्थं तपरत्वं स्थितम्॥ प्लुतविधौ तु **वाक्यस्य टे**रित्यधिकारात्कथमिकारस्य प्लुतः स्यादिति चिन्त्यमेतत् ॥ १७ ॥

(उद्द्योतः) **यद्यनेनेति** । टिग्रहणं वाक्येनैव संबध्यते नत्वनन्त्येन पदेनेति भावः ॥ भाष्ये **विषये** प्रश्नाख्यानादिविषये प्लुत उच्यते । यदा स विषयो भवति तदाप्यनेनैव सूत्रेण प्लुतेन भाव्यमित्यनुवाददोषभिया नानेन प्लुतविधानमित्ययमत्र पक्षे भाष्याक्षरार्थः कार्यः ॥ **अन्ये त्विति** । **अनन्तरेपीति** । सूत्रेऽसदृशे आदेशे श्रूयमाणेपीत्यर्थः । **क्रियमाण** इति पाठेपि श्रूयमाण इत्येवार्थः ॥ **दीर्घ एवेति** । आन्तर्यादिति भावः । वार्तिके **ऽनन्तरे** इत्यस्यानन्तरे श्रूयमाणेपि दीर्घः स्यादिति शेषो बोध्यः ॥ **प्लुतो मा भूदिति** शङ्कोत्तरत्वेनावतारयति—**नन्विति** ॥ **स्यादिति** । तथा च तत्र प्लुत इष्टः । स चासति तपरत्वे पुनर्विहितेन दीर्घेण बाधितः सन्न स्यादित्यर्थः ॥ ननु किमिति प्लुतस्तत्रेष्यत इति शङ्कते—**मा भूदिति** ॥ **स्मृत इति** । एवं च प्रश्नाख्यानादिविषये तस्येष्टत्वान्न तन्निवृत्त्यर्थं विधानमित्यर्थः । **सचासतीति** । सिद्धे दीर्घे दीर्घविधानसामर्थ्येन बाधादित्यर्थः । सति तु तपरत्वे दीर्घाप्राप्त्या प्लुतो निर्विघ्न इति भावः ॥ पश्चात्प्राप्तस्तु तपरत्वेन न बाध्यते ऽसिद्धत्वादित्याशयः ॥ प्रकारद्वयमपि दूषयति—**प्लुतेति** । अनन्त्यस्य पदस्य टेः, अपिना वाक्यस्य च टेः प्लुतः प्रश्नाख्यानयोरित्यर्थस्तस्येति भावः ॥ टिग्रहणं वाक्येनैव सम्बध्यते न त्वनन्त्येन पदेनेति तु भाष्यतात्पर्यम् ॥ यत्त्वदिद्धमित्यादौ **गुरोरनृत** इत्येतद्विषयं भाष्यमिति । तन्न । तेन हूयमानार्थवाचिन एव टेः प्लुतविधानादित्याहुः ॥ १७ ॥

(७८ कित्त्वाभावातिदेशसूत्रम् ॥ १ । २ । १ आ. १० सू.)

९२ न क्त्वा सेट् ॥ १ । २ । १८ ॥

(क्त्वाग्रहणप्रत्याख्यानाधिकरणम्)

(६०१ सिद्धान्तवार्तिकम् ॥ १ ॥)

॥ * ॥ न सेडिति कृते ऽकित्त्वे ॥ * ॥

(भाष्यम्)

न सेडित्येव सिद्धम्, नार्थः क्त्वाग्रहणेन ॥

(प्रदीपः) न क्त्वा ॥ १८ ॥ कृतेऽकित्त्वे इति । अकारप्रश्लेषः ॥

(उद्द्योतः) न क्त्वा ॥ १८ ॥ न सेडित्यनेन कथं कित्त्वं क्रियेतेत्यत आह—अकारेति ॥

(आक्षेपभाष्यम्)

निष्ठायामपि तर्हि प्राप्नोति—गुधितः गुधितवानिति ॥

(६०२ समाधानवार्तिकम् ॥ २ ॥)

॥ * ॥ निष्ठायामवधारणात् ॥ * ॥

(भाष्यम्)

निष्ठायामवधारणान्न भविष्यति ॥ किमवधारणम्? ॥ "निष्ठा शीङ्स्विदिमिदिक्ष्विदिधृषः" इति।

(प्रदीपः) निष्ठायामिति । शीङादिभ्य एव परा निष्ठा न किदिति नियमः । विपरीतस्तु निष्ठैवेति व्याख्यानान्न भवति ॥

(उद्द्योतः) विपरीतस्त्विति । तथाहि सति शयित्वेत्यादावपि कित्त्वं स्यादित्यर्थः ॥

(आक्षेपभाष्यम्)

परोक्षायां तर्हि प्राप्नोति ॥ किं च स्यात्? ॥ पपिव पपिम क्ङितीत्याकारलोपो न स्यात् ॥

(प्रदीपः) परोक्षायामिति । पूर्वाचार्यप्रसिद्ध्या परोक्षा लिडुच्यते ॥

(आक्षेपबाधकभाष्यम्)

मा भूदेवम्, इटीत्येवं भविष्यति ।

(आक्षेपसाधकभाष्यम्)

इदं तर्हि—जग्मिव जघ्निव क्ङितीत्युपधालोपो न स्यात् ॥

(६०३ समाधानवार्तिकम् ॥ ३ ॥)

॥ * ॥ ज्ञापकान्न परोक्षायाम् ॥ * ॥

(भाष्यम्) **ज्ञापकात्परोक्षायां न भविष्यति ॥**

(आक्षेपभाष्यम्)

किं ज्ञापकम्? ॥

(६०४ समाधानवार्तिकम् ॥ ४ ॥)

॥ * ॥ सनि झल्ग्रहणं विदुः ॥ * ॥

(भाष्यम्) **यदयम् "इको झल्" इति झल्ग्रहणं करोति तज्ज्ञापयत्याचार्यः—'औपदेशिकस्य कित्त्वस्य प्रतिषेधो नातिदेशिकस्य' इति ॥ कथं कृत्वा ज्ञापकम्? ॥ झल्ग्रहणस्यैतत्प्रयोजनं झलादौ यथा स्यात् । इह मा भूत्—शिशयिषत इति । यदि चात्रातिदेशिकस्यापि कित्त्वस्य प्रतिषेधः स्यात्, झल्ग्रहणमनर्थकं स्यात् । अस्त्वत्र कित्त्वम्, 'न सेड्' इति प्रतिषेधो भविष्यति । पश्यति त्वाचार्य औपदेशिकस्य कित्त्वस्य प्रतिषेधो नातिदेशिकस्येति, ततो झल्ग्रहणं करोति ॥**

(प्रदीपः) अस्त्वत्रेति । प्राप्नोतु कित्त्वमित्यर्थः । न तु निर्वृत्तस्य निषेधः कर्तुं शक्यः ॥

(उद्द्योतः) न तु निर्वृत्तस्येति । ननैवं क्त्वोपि विद्यमानस्य कित्त्वस्य कथं निषेध इति वाच्यम् । कार्यस्यैव निषेधो न तु विद्यमानकित्त्वस्येति न दोषः । आतिदेशिकस्य निर्वृत्तस्य निषेधे तु तेन कृतकित्कार्यस्यानेन प्रतिषेधे विरोधः स्पष्ट एवेति दिक् ॥

(समाधानबाधकभाष्यम्)

नैतदस्ति ज्ञापकम् । उत्तरार्थमेतत्स्यात् "स्थाघ्वोरिच्च" झलादौ यथा स्यात् । इह मा भूत्—उपास्थायिषाताम् उपास्थायिषत ॥

(प्रदीपः) उपास्थायिषतामिति । स्थास् आतामिति स्थिते इत्त्वं च प्राप्नोति चिण्वद्भावश्च । तत्र परत्वाच्चिण्वद्भावे युक् च प्राप्नोति वृद्धिश्च । तत्र वृद्ध्यपवादो युगागमः । तत्र कृते यकारस्येत्त्वप्रसङ्गः । न च पुनर्वृद्धिर्लभ्यते । पूर्वमेव युका बाधितत्वादिति भावः ॥

(उद्द्योतः) ननु झल्ग्रहणाभावेपि सिचश्चिण्वदिटि इत्वे वृद्धावायादेशे च सिद्धमित्यत आह—स्थासिति । तत्र चिण्वद्भावे परत्वात् कृते इत्यन्वयः ॥ वृद्ध्यपवाद इति । येननाप्राप्तिन्यायेन, नत्वनवकाशत्वेनेति भावः । तदेवाह—न च पुनरिति ॥

(६०५ समाधानसाधकवार्तिकम् ॥ ५ ॥)

॥ * ॥ इत्त्वं कित्संनियोगेन ॥ * ॥

(भाष्यम्) **कित्त्वसंनियोगेनेत्त्वमुच्यते । तेनासति कित्त्वे इत्त्वं न भविष्यति ॥**

(प्रदीपः) असति कित्त्व इति । झल्ग्रहणस्य ज्ञापकत्वं न तावत्स्थितमिति आतिदेशिकस्यापि कित्त्वस्य न सेडिति निषेधो भवतीत्यभिप्रायः ॥

(उद्द्योतः) भाष्ये इत्त्वं कित्त्वसंनियोगेनेति ॥ उत्तरार्थत्वं खण्डयति ॥ तदाह—आतिदेशिकस्यापीति । तथा च कित्त्वनिषेधे तत्संनियुक्तेत्त्वस्याप्यभाव इति भावः । ज्ञापिते त्वातिदेशिकानिषेधे उत्तरत्राप्युपयोग इत्यन्यत् ॥

(६०६ दृष्टान्तवार्तिकम् ॥ ६ ॥)

॥ * ॥ रेण तुल्यं सुधीवनि ॥ * ॥

(भाष्यम्) तद्यथा—सुधीवा सुपीवेति ङीप्सं-नियोगेन र उच्यमानो ऽसति ङीपि न भवति ॥

(प्रदीपः) सुधीवनीति । अनो बहुव्रीहेरिति प्रकृतस्यैव ङीपो निषेधो न तु रेफस्यापि, स तु सन्नियोगशिष्टानामन्यतरापाये उभयोरप्यपाय इति न्यायान्निवर्त्तते । अयं न्यायो बिल्वकादिभ्यश्छस्य लुगित्यत्र छग्रहणेन ज्ञापितः॥

(उद्योतः) नन्वनो बहुव्रीहेरित्यस्य स्त्रियां विहितं नेत्यर्थाद् रेफस्यापि निवृत्तिर्वाचनिकीति विषमो दृष्टान्तोऽत आह—अन इति । प्रत्ययाधिकारात्प्रत्ययस्यैव निषेध इति भावः ॥ छग्रहणेनेति । तद्धि बिल्वकादेरुत्तरस्य प्रत्ययस्य भनिमित्ते तद्धिते विधीयमानो लुक् प्रत्ययान्तराभावात् छस्यैव सिद्ध इति छमात्रस्य लुग्यथा स्याद् न तु तत्सन्नियोगशिष्टकुको निवृत्तिरित्यर्थमिति भावः।

(इत्त्वेपीष्टापत्तिभाष्यम्)

अथ वा ऽस्त्वत्रेत्त्वम् ॥ का रूपसिद्धिः ? ॥ वृद्धौ कृतायामायादेशो भविष्यति ॥

(प्रदीपः) अस्त्वत्रेति । यकारस्य कृते इत्त्वे वृद्धिर्भविष्यति । युगागमेन ह्याकारस्य वृद्धिर्बाध्यते, नत्विकारस्यापि ॥

(उद्योतः) ननु युका वृद्धेर्बाधितत्वात्कथमिकारस्य वृद्धिरत आह—युगागमेनेति । तत्प्राप्तिवेलायामिकाराभावेन तत्र वृद्धेरप्राप्तेरिति भावः ॥ भ्रष्टावसरन्यायस्तु शास्त्रे नास्त्येवेति तात्पर्यम् ॥ वस्तुतो ऽथ वास्त्वत्रेत्वमिति भाष्यमेकदेश्युक्तिर्विन्मतोर्लुका टिलोपमात्रबाधवत्तत्राप्यापत्तेरिति बोध्यम् । तस्माद् झल्ग्रहणस्य ज्ञापकत्वं स्थितम्—औपदेशिकस्यैव निषेध इति ॥

(६०७ प्रयोजनवार्तिकम् ॥ ७ ॥)

॥ * ॥ वस्वर्थम् ॥ * ॥

(भाष्यम्) वस्वर्थं तर्हि क्त्वाग्रहणं कर्तव्यम् । वसोर्ह्यौपदेशिकं कित्त्वम् ॥ किं च स्यात् ? ॥ पपिवान् तस्थिवान् कितीत्याकारलोपो न स्यात् ॥

(प्रयोजनबाधकभाष्यम्)

मा भूदेवम् ' इटीत्येवं भविष्यति ॥

(प्रयोजनसाधकभाष्यम्)

इदं तर्हि जग्मिवान् जघ्निवान् कितीत्युपधालोपो न स्यात् ॥

(६०८ प्रयोजनबाधकवार्तिकम् ॥ ८ ॥)

॥ * ॥ किदतिदेशात् ॥ * ॥

(भाष्यम्) अस्त्वत्रौपदेशिकस्य कित्त्वस्य प्रतिषेधः । आतिदेशिकमत्र कित्त्वं भविष्यति ॥

(उद्योतः) भाष्ये—आतिदेशिकमिति । असंयोगाल्लिडित्यनेन ॥

(प्रयोजनसाधकभाष्यम्)

यत्र तर्हि तत्प्रतिषिध्यते—अञ्जेः—आजिवानिति ॥

(प्रदीपः) आजिवानितीति । इदं नोपपद्यते । अत्र हि नलोपे कृते द्विर्वचने एकादेशे च वस्वेकाजाद्धसामितीडागमः । तत्र हि कित्त्वप्रतिषेधान्नलोपनिवृत्तौ द्विहल्त्वान्नुटि सत्येकाच्त्वाभावादिण्निवृत्तौ नलोपादीनां चक्रकप्राप्तिः । चक्रकेषु चेष्टतो व्यवस्था ॥ भाष्यकारेण तु परिहारान्तरसद्भावादेष परिहारो नाश्रितः ॥

(उद्योतः) आजिवानिति । द्वित्वात्परत्वात्पूर्वमिटि न सेडिति निषेधेन कित्त्वाभावान्नलोपाभावे ऽसंयोगादित्यस्याप्राप्तेर्नलोपसिद्धये क्त्वाग्रहणम् । संज्ञापेक्षाकृतं बहिरङ्गत्वं त्वत्र शास्त्रे नाश्रीयत इति भावः ॥ एकादेशे च वस्वेकाजिति । कृतद्विर्वचनानामेकाचामिति स्थितत्वादिति भावः ॥ नलोपनिवृत्ताविति । निमित्तापायन्यायेनेति भावः ॥ द्विहल्त्वादिति । तस्मान्नुडित्यनेन नुडिति भावः ॥ इण्निवृत्ताविति । तन्निवृत्तौ सत्यां कित्वान्नलोपे ऽद्विहल्त्वान्नुण्निवृत्तावेकादेशेनैकाच्त्वादिटि सेट्त्वात्कित्त्वप्रतिषेध इत्येवं नलोपादीनां चक्रकप्राप्तिरित्यर्थः ॥ इष्टत इति । सा चौपदेशिककित्त्वेन नलोपे इटः प्रवृत्ताविष्टसिद्धिरूपा इत्यर्थः ॥ उक्तन्यायस्य भाष्यकृतानङ्गीकारेण चक्रकप्राप्तिरेव नेत्यन्ये॥

(प्रयोजनबाधकभाष्यम्)

एवं तर्हि च्छान्दसः क्वसुः । लिट् च च्छन्दसि सार्वधातुकमपि भवति। तत्र सार्वधातुकमपिन्ङिद्भवतीति ङित्युपधालोपो भविष्यति ॥

(६०९ प्रयोजनवार्तिकम् ॥ ९ ॥)

॥ * ॥ (नि) गृहीतिः ॥ * ॥

(भाष्यम्) इदं तर्हि प्रयोजनम् । इह मा भूत्—निगृहीतिः । उपस्निहितिः निकुचितिः ॥

(प्रदीपः) निगृहीतिरिति । तितुत्रेष्वग्रहादीनामितीडागमः ॥

(उद्योतः) तितुत्रेत्यादिनेडागमप्रतिषेधः किं न स्यादत आह—अग्रहादीनामिति ।

(आक्षेपभाष्यम्)

तत्तर्हि क्त्वाग्रहणं कर्तव्यम् ॥

(प्रत्याख्यानभाष्यम्)

न कर्तव्यम् ॥

(६१० प्रत्याख्यानसाधकवार्तिकम् ॥ १०॥)

॥ * ॥ क्त्वा च विग्रहात् ॥ * ॥

(भाष्यम्) उपरिष्टाद् योगविभागः करिष्यते— "न सेड् निष्ठा शीङ्स्विदिमिदिक्ष्विदिधृषः" "मृषस्तितिक्षायाम्" "उदुपधाद्भावादिकर्मणोरन्यतरस्याम्"। ततः—"पूङः" पूङश्च निष्ठा सेट् किन्न भवति। ततः—"क्त्वा च" क्त्वा च सेट् किन्न भवति! पूङ इति निवृत्तम् ॥

न सेडिति कृते ऽकित्त्वे निष्ठायामवधारणात्।
ज्ञापकान्न परोक्षायां सनि झल्ग्रहणं विदुः ॥ १ ॥
इन्वं कित्संनियोगेन रेण तुल्यं सुधीवनि।
वस्त्वर्थे किदतीदेशाद् गृहीतिः क्त्वा च विग्रहात् ॥ २ ॥ न क्त्वा सेट् ॥ १८ ॥

(प्रदीपः) क्त्वा च विग्रहादिति। विग्रहो विभागो योगस्य करिष्यत इत्यर्थः ॥ १८ ॥

(उद्द्योतः) अतीदेशादित्यत्रोपसर्गस्य घञोनि दीर्घः १८॥

(७९ कित्त्वाभावातिदेशसूत्रम् ॥ १।२।१। आ. ११ सू.)

९५ उदुपधाद्भावादिकर्मणोरन्यतरस्याम् ॥ १ । २ । २१ ॥

(आक्षेपभाष्यम्)

इह कस्मान्न भवति—गुधितः गुधितवान् ? ॥

(६११ समाधानवार्तिकम् ॥ १ ॥)

॥ * ॥ उदुपधाच्छपः ॥ * ॥

(भाष्यम्) शब्विकरणेभ्य इष्यते॥उदुपधाद्२१॥

(प्रदीपः) उदु ॥ २१ ॥ उदुपधाच्छप इति। शपः संबन्धी शब्विकरणो यस्तस्मादित्यर्थः ॥ २१ ॥

(उद्द्योतः) उदुपधाद् ॥ २१ ॥ शप इत्यस्य पञ्चम्यन्तत्वे शबन्तोदुपधात्परनिष्ठासम्भवः इत्यत आह—शपः सम्बन्धीति २१

(८० कित्त्वातिदेशसूत्रम् ॥ १ . २ । १ आ. १२ सू.)

९६ पूङः क्त्वा च ॥ १ । २ । २२ ॥

(६१२ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ पूङः क्त्वानिष्ठयोरिटि वाप्रसङ्गः सेट्प्रकरणात् ॥ * ॥

(भाष्यम्) पूङः क्त्वानिष्ठयोरिटि विभाषा कित्त्वं प्राप्नोति। किं कारणम् ? ॥ सेट्प्रकरणात्। सेडिति वर्तते ॥

(प्रदीपः) पूङः॥२२॥पूङ इति। सेडित्यन्यतरस्यामिति चानुवर्तनात्सेटोरेव क्त्वानिष्ठयोः कित्त्वविकल्पः स्यात्। ततश्च पुविला पुवित इति पक्षे स्यात्। अस्ति चेडागमः पूङश्चेति विकल्पेनेड्विधानात् ॥

(उद्द्योतः) पूङः क्त्वा च ॥ २२ ॥ नन्विटि वाप्रसङ्ग इत्यत्र सेट्प्रकरणादिति हेतुर्न्यूनोत आह—अन्यतरस्यामिति चेति ॥ ननु श्र्युकः क्तिीति निषेधात्कित्त्वनिषेधं विनेडेव दुर्लभ इति सेडनुवृत्तिरयुक्तेत्यत आह—अस्ति चेति ॥

(६१३ समाधानवार्तिकम् ॥ २ ॥)

॥ * ॥ न वा सेट्त्वस्याकिदाश्रयत्वादनिटि वा कित्त्वम् ॥ * ॥

(भाष्यम्) न वा एष दोषः ॥ किं कारणम्? ॥ सेट्त्वस्याकिदाश्रयत्वाद्। अकिदाश्रयं सेट्त्वम्। यदा अकित्त्वं तदेटा भवितव्यम्। सेट्त्वस्याकिदाश्रयत्वादनिट्येव विभाषा कित्त्वं भविष्यति ॥

(प्रदीपः) न वेति। इड्विधौ पूङश्चेति सूत्रं वार्तिककारः प्रत्याचष्टे। तत्रानिटोरेव क्त्वानिष्ठयोरनेन कित्त्वं विकल्प्यते। तत्र यदा कित्त्वं तदा श्र्युकः क्तिीति इट्प्रतिषेधात्पूत्वा पूत इति भवति। यदा त्वकित्त्वं तदेड्गुणयोः पविला पवित इति भवति ॥

(उद्द्योतः) ननु सति पूङश्चेत्यस्मिन् कथमकिदाश्रयं सेट्त्वमत आह—इड्विधाविति ॥

(आक्षेपभाष्यम्)

इड्विधौ पूङो ग्रहणं क्रियते। तेन वचनादिट्। सेट्प्रकरणाच्च इट्येव विभाषा कित्त्वं प्राप्नोति ॥

(६१४ समाधानवार्तिकखण्डम् ॥ ३ ॥)

॥ * ॥ इड्विधौ च ग्रहणम् ॥ * ॥

(भाष्यम्) इड्विधौ हि पूङो ग्रहणं न कर्तव्यं भवति ॥

भारद्वाजीयाः पठन्ति—

(वार्तिकम् ॥)

॥ * ॥ नित्यमकित्त्वमिडाद्योः क्त्वाग्रहणमुत्तरार्थम् ॥ * ॥

(भाष्यम्) नित्यमकित्त्वमिडाद्योः क्त्वानिष्ठयोः

सिद्धम् ॥ कथम् ? ॥ विभाषामध्येऽयं योगः क्रियते। विभाषामध्ये च ये विधयस्ते नित्या भवन्ति॥ किमर्थं तर्हि क्त्वाग्रहणम् ? ॥ क्त्वाग्रहणमुत्तरार्थम् । उत्तरार्थं क्त्वाग्रहणं क्रियते—"नोपधात्थफान्ताद्वा" "वञ्चिलुञ्च्यृतश्च" इति ॥ पूङः क्त्वा च ॥ २२ ॥

(प्रदीपः) भारद्वाजीया इति । लाघवमनादृत्य सूत्रकारेण पूङश्चेतीद्विधौ पठितम् । इह तु विकल्पो नानुवर्तते उत्तरत्र वाग्रहणादिति सिद्ध्यतीष्टमिति भावः ॥ उत्तरार्थमिति । न क्त्वा सेडिति किन्त्वप्रतिषेधस्य सिद्धत्वात् ।

(उद्द्योतः) ननु गौरवाद्भारद्वाजीयं मतमयुक्तमत आह—लाघवमिति ॥ विभाषामध्ये इति । विभाषयोर्मध्य इत्यर्थः ॥ किमर्थं तर्हि क्त्वाग्रहणमिति प्रश्नो भारद्वाजीयमते बोध्यः ॥ नन्विड्विधौ सम्भवति कथमुत्तरार्थत्वमत आह—न क्त्वेति ॥ २२ ॥

(८१ किद्वदतिदेशसूत्रम् ॥ १।२।१ आ. १३ सू.)

९९ तृषिमृषिकृशेः काश्यपस्य ॥ १ । २ । २५ ॥

(आक्षेपभाष्यम्)

काश्यपग्रहणं किमर्थम् ? ॥

(समाधानभाष्यम्)

काश्यपग्रहणं पूजार्थम्। वेत्येव हि वर्तते ॥ तृषिमृषिकृशेः काश्यपस्य ॥ २५ ॥

(प्रदीपः) तृषि ॥२५॥ पूजार्थमिति । शास्त्रस्य पूजापारम्पर्यप्रतिपादनेनानाविच्छेदप्रामाण्यप्रतिपादनात् ॥ २५ ॥

(उद्द्योतः) तृषिमृ ॥ २५ ॥ पारम्पर्यप्रतिपादनेनेति । चातुर्वर्ण्यादिवत्स्वार्थे ष्यञ् । परम्पराप्रतिपादनेनेत्यर्थः ॥ २५ ॥

(८२ किद्वदतिदेशसूत्रम् ॥ १।२।१ आ. १४ सू.)

१०० रलो व्युपधाद्धलादेः संश्च ॥ १ । २ । २६ ॥

(आक्षेपभाष्यम्)

किमिदं रलः क्त्वासनोः कित्त्वं विधीयते । आहोस्वित्प्रतिषिध्यते ? ॥ किं चातः ? ॥ यदि विधीयते, क्त्वाग्रहणमनर्थकम्। किदेव हि क्त्वा॥ अथ प्रतिषिध्यते, सन्ग्रहणमनर्थकम् । अकिदेव हि सन् ॥

(प्रदीपः) रलो ॥२६॥ किमिदमिति। किमियमप्राप्ते विभाषा, आहोस्वित् प्राप्त इति प्रश्नः । तत्राप्राप्तविभाषायां सन एवाप्राप्तं कित्त्वं पक्षे विधीयत इति क्त्वानुवृत्तिरनर्थिका । नहि तस्य कित्त्वं विधेयं स्वत एव भावात् । अथ प्राप्तविभाषा तदा क्त्वः कित्त्वमस्तीति तस्यैव पक्षे निषेधः कर्तव्य इति सन्ग्रहणं न कार्यं नहि तस्य कित्त्वमस्ति यत्पक्षे निषिध्यते ॥

(उद्द्योतः) रलो व्यु ॥ २६ ॥ वेत्यनुवृत्तेरुभयथापि विकल्पसिद्धेर्विचारोऽनुपपन्न इत्यतस्तात्पर्यमाह—किमिति ॥

(समाधानभाष्यम्)

अत उत्तरं पठति—

(६१५ प्रथमपक्षाङ्गीकारवार्तिकम् ॥ ॥)

॥ * ॥ रलः क्त्वासनोः कित्त्वम् ॥ * ॥

(भाष्यम्) रलः क्त्वासनोः कित्त्वं विधीयते ॥

(प्रदीपः) रल इति । अप्राप्तविभाषेयमेकेनैव रूपेण व्यवस्थितेत्यर्थः । एकरूपत्वप्रदर्शनाय च विचारः कृतः । ननूभयत्रविभाषा न सन्ति, प्रतिलक्ष्यं व्यापाराश्रयणे तासां सिद्धत्वात् ॥ २६ ॥

(उद्द्योतः) ननु क्वचिद्विधिमुखेन क्वचिन्निषेधमुखेन व्यापारादुभयत्र विभाषास्तु प्रतिलक्ष्यं लक्षणभेदादत आह—एकरूपत्वेति । व्यापारैक्ये सम्भवति तद्भेदाङ्गीकारो निष्फल इति भावः ॥ २६ ॥

(आक्षेपस्मारणभाष्यम्)

ननु चोक्तम्—क्त्वाग्रहणमनर्थकम्—इति ॥

(समाधानभाष्यम्)

नानर्थकम् । 'न क्त्वा सेट्' इति प्रतिषेधः प्राप्नोति तद्बाधनार्थम् ॥ रलो व्युपधाद्धलादेः संश्च ॥ २६ ॥

(इति कित्प्रकरणम् ॥)

(८३ ह्रस्वादिसंज्ञासूत्रम् ॥ १।२।१ आ. १५ सू०)

१०१ ऊकालोऽज्झ्रस्वदीर्घप्लुतः॥१।२।२७॥

(सौत्रनिर्देशसाधुत्वाधिकरणम्)

(आक्षेपभाष्यम्)

अयुक्तोऽयं निर्देशः । ऊ इत्यनेन कालः प्रतिनिर्दिश्यते । ऊ इत्ययं च वर्णः । तत्रायुक्तं वर्णस्य कालेन सह सामानाधिकरण्यम् ॥

कथं तर्हि निर्देशः कर्तव्यः ? ॥

ऊकालकाल इति ॥

किमिदमूकालकाल इति ? ॥

ऊ इत्येतस्य काल ऊकालः, ऊकालः कालो यस्य स ऊकालकाल इति ॥

(प्रदीपः) ऊकालः ॥ २७ ॥ मयुकोयमिति । तपरस्तत्कालस्येत्यत्र व्याख्यातत्वादिह न व्याख्यायते ॥

(उद्द्योतः) ऊकालो ॥ २७ ॥ भाष्ये—प्रतिनिर्दिश्यत इति । विशेष्यत इत्यर्थः ॥ ऊकालः कालो यस्येति । ऊकाल इव कालो यस्येत्यर्थः ॥

(तटस्थाक्षेपभाष्यम्)

स तर्हि तथानिर्देशः कर्तव्यः ॥

(समाधानभाष्यम्)

न कर्तव्यः। उत्तरपदलोपोत्र द्रष्टव्यः। तद्यथा—उष्ट्रमुखमिव मुखमस्य उष्ट्रमुखः। खरमुखः। एव मूकालकाल ऊकाल इति ॥ अथ वा साहचर्यात्ताच्छब्द्यं भविष्यति। कालसहचरितो वर्णः। वर्णोपि काल एव ॥

(यथासंख्योपपादनाधिकरणम्)

(६१६ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ ह्रस्वादिषु समसंख्याप्रसिद्धिर्निर्देशवैषम्यात् ॥ * ॥

(भाष्यम्) ह्रस्वादिषु समसंख्यत्वस्याप्रसिद्धिः॥ किं कारणम्? ॥ निर्देशवैषम्यात् । तिस्रः संज्ञा एकः संज्ञी । वैषम्यात्संख्यातानुदेशो न प्राप्नोति॥

(प्रदीपः) ह्रस्वादिष्विति। ऊ इत्येकस्यैव शब्दस्योच्चारणाद्भेदानवगमात् संज्ञिविशेषणस्यैकत्वे सति संज्ञिनोप्येकत्वात्। संज्ञानां च त्रित्वात्संख्यातानुदेशाप्रसङ्गः ॥

(उद्द्योतः) ननूकालानां वर्णानां बहुत्वाद् एकः संज्ञीत्यनुपपन्नमत आह—ऊ इत्येकस्येति । उपात्तद्विमात्रत्वाकारेणैक इति भावः ॥ संज्ञिविशेषणस्येति । ऊ इत्यस्येत्यर्थः ॥ संज्ञानां चेति । प्रदेशेषु त्रिविधव्यवहारदर्शनादिति भावः ॥ भाष्ये—संख्यातानुदेश इति । संख्यातं सम्यग्ज्ञानमनतिक्रम्यानुदेशः संबन्ध इत्यर्थः। सुप्सुपेति समासः। ज्ञानक्रमेणान्वय इति यावत् ॥

(६१७ (१) समाधानवार्तिकम् ॥ २ ॥)

॥ * ॥ सिद्धं तु समसंख्यत्वात् ॥ * ॥

(भाष्यम्) सिद्धमेतत् ॥ कथम्? ॥ समसंख्यत्वात् ॥

(प्रदीपः) सिद्धं त्विति । त्रयाणां कृतैकादेशानां निर्देशाद्विशेषणत्रयावच्छिन्नत्वात्संज्ञिनामपि त्रित्वाद्यथासंख्यं संबन्धः सिद्ध इत्यर्थः। अर्थतश्च साम्यं यथासंख्यसूत्रे आश्रीयते न शब्दत एव ॥ अथ वा शब्दतः साम्याश्रयणेपि संहितावशादैक्यमिव प्राप्तास्त्रयः शब्दा उच्चारिता इत्यदोषः ॥

(उद्द्योतः) नन्वेवमर्थतः समसंख्यत्वेपि शब्दतस्तदभावात्कथं यथासंख्यसूत्रप्राप्तिरत आह—अर्थतश्चेति । अत एव परस्मैपदानां णलित्यादौ यथासंख्यमिति भावः । ऊशब्दस्य त्रयोऽर्था इति तात्पर्यम् ॥ त्रयः शब्दा इति । वैयाकरणैस्तथा सुज्ञेयत्वादिति भावः ॥

(आक्षेपभाष्यम्)

कथं समसंख्यत्वम्? ।

(६१७ (२) समाधानसाधकवार्तिकखण्डम् ॥ २ ॥)

॥ * ॥ त्रयाणां हि विकारनिर्देशः ॥ * ॥

(भाष्यम्) त्रयाणामयं प्रश्लिष्टनिर्देशः ॥ कथं पुनर्ज्ञायते—त्रयाणामयं प्रश्लिष्टनिर्देश इति? । तिसृणां संज्ञानां करणसामर्थ्यात् ॥

(प्रदीपः) कथं पुनरिति । प्रत्यक्षेणैकस्यैव शब्दस्य श्रवणाद्भेदावगमे प्रमाणाभाव इति भावः ॥ तिसृणामिति । अनुमानाद्भेदावसाय इति भावः ॥

(उद्द्योतः) भाष्ये विकारो दीर्घरूपः, तेन निर्देश इति तृतीयातत्पुरुषः । तदाह—प्रश्लिष्टेति ॥ अनुमानादिति । अनेकसंज्ञाकरणात्संज्ञिनां शब्दतो भेदावसाय इत्यर्थः । प्रयोगस्तु विगताः संज्ञा भिन्नसंज्ञिविषयाः नानासंज्ञात्वादिति ॥

(आक्षेपभाष्यम्)

यद्यपि तावत्तिसृणां संज्ञानां करणसामर्थ्याज्ज्ञायते—त्रयाणामयं प्रश्लिष्टनिर्देश इति । कुतस्त्वेतदेतेनानुपूर्व्येण संनिविष्टानां संज्ञा भविष्यतीति आदौ मात्रिकस्ततो द्विमात्रस्ततस्त्रिमात्र इति। न पुनर्मात्रिको मध्ये वान्ते वा स्यात्। तथा द्विमात्र आदौ वा स्यादन्ते वा । तथा त्रिमात्र आदौ वा मध्ये वा स्यात्? ॥

(समाधानभाष्यम्)

अयं तावत् त्रिमात्रोऽशक्य आदौ वा मध्ये वा कर्तुम् ॥ कुतः? ॥ प्लुताश्रयो हि प्रकृतिभावः प्रसज्येत ॥ मात्रिकद्विमात्रिकयोरपि ब्यन्तं पूर्वं निपततीति मात्रिकस्य पूर्वनिपातो भविष्यति ॥

(प्रदीपः) अयंतावदिति । लौकिकव्यवहाराश्रयणेन प्लुतत्वं ह्रस्वत्वं च सिद्धमाश्रित्यैतदुच्यते ॥

(उद्द्योतः) भाष्ये—प्लुताश्रय इति । न नु मध्ये करणे कथं प्लुताश्रयः प्रकृतिभाव इति वाच्यम्। मध्ये त्रिमात्रसत्त्वे पूर्वेण दीर्घे त्रिमात्रस्यैवापत्तौ लोकाश्रयप्लुतत्वमादायाग्रिमेण सन्धौ कर्तव्ये प्रकृतिभावापत्तिः । संख्याव्यवहार इव दीर्घादिव्यवहारोपि लौकिकशास्त्रीयोभयविषय इत्यभिमानस्तदाह—लौकिकेति ॥

(समाधानबाधकभाष्यम्)

यत्तावदुच्यते—अयं तावत् त्रिमात्रोऽशक्य आदौ मध्ये वा कर्तुं प्लुताश्रयो हि प्रकृतिभावः प्रसज्येतेति। प्लुताश्रयः प्रकृतिभावः । प्लुतसंज्ञा

चानेनैव। यदि च त्रिमात्र आदौ वा मध्ये वा स्यात् प्लुतसंज्ञैवास्य न स्यात्। कुतः प्रकृतिभावः॥ यदप्युच्यते मात्रिकद्विमात्रिकयोरपि घ्यन्तं पूर्वं निपततीति मात्रिकस्य पूर्वनिपातो भविष्यतीति। ह्रस्वाश्रया हि घिसंज्ञा, ह्रस्वसंज्ञा चानेनैव। यदि च मात्रिको मध्ये वान्ते वा स्यात् ह्रस्वसंज्ञैवास्य न स्यात्। कुतो घिसंज्ञा कुतः पूर्वनिपातः। एवमेषा व्यवस्था न प्रकल्पते॥

(प्रदीपः) यत्तावदिति। शास्त्रात्स्थितायां ह्रस्वादिव्यवस्थायां लोके ह्रस्वादिव्यवहारो नान्यथेति भावः॥

(उद्द्योतः) शास्त्रादिति। लौकिकव्यवहारोप्यनादिशास्त्रसंस्कारपूर्वकः, अन्यथा संज्ञाकरणानर्थक्यमिति भावः॥

(समाधानसाधकभाष्यम्)

एवं तर्ह्याचार्यप्रवृत्तिर्ज्ञापयति—न मात्रिकोन्ते भवतीति। यदयं—"विभाषा पृष्टप्रतिवचने हेः" इति मात्रिकस्य प्लुतं शास्ति॥ कथं कृत्वा ज्ञापकम्?। योन्ते स प्लुतसंज्ञः। यदि च मात्रिकोन्ते स्यात्। प्लुतसंज्ञाऽस्य स्यात्। तत्र हि मात्राकालस्य मात्राकालवचनमनर्थकं स्यात्॥

मध्ये तर्हि स्यादिति॥ अत्राप्याचार्यप्रवृत्तिर्ज्ञापयति—न मात्रिको मध्ये भवतीति। यदयम्—"अतो दीर्घो यञि, सुपि च" इति दीर्घत्वं शास्ति॥ कथं कृत्वा ज्ञापकम्?। यो मध्ये स दीर्घसंज्ञकः। यदि च मात्रिको मध्ये स्याद्दीर्घसंज्ञास्य स्यात्। तत्र मात्राकालस्य मात्राकालवचनमनर्थकं स्यात्॥

द्विमात्रस्तर्ह्यन्ते स्यादिति॥ अत्राप्याचार्यप्रवृत्तिर्ज्ञापयति—न द्विमात्रोन्ते भवतीति। यदयम्—"ओमभ्यादाने" इति द्विमात्रिकस्य प्लुतं शास्ति॥ कथं कृत्वा ज्ञापकम्?। योन्ते स प्लुतसंज्ञः। यदि च द्विमात्रोन्ते स्यात् प्लुतसंज्ञास्य स्यात्। तत्र द्विमात्राकालस्य द्विमात्राकालवचनमनर्थकं स्यात्। मात्रिकेण चास्य पूर्वनिपातो बाधित इति कृत्वा क्वान्यत्रोत्सहते भवितुमन्यदतो मध्यात्। एवमेषां व्यवस्था प्रक्लृप्ता॥

(प्रदीपः) यदयमिति। अनन्तरतमादेशविधानार्थमेतत्स्यादिति चेत्॥ तन्न। नहि स्थानेन्तरतम इत्यस्याः परिभाषायाः प्रत्यक्षायाः बाधा युक्तेति विशिष्टानुपूर्वीप्रतिपत्तौ लिङ्गत्वमेव प्लुतविधानस्य॥ मात्रिकेणेति। लिङ्गद्वयेनान्तमध्याभ्यां मात्रिकस्यापकृष्टत्वादित्यर्थः॥

(उद्द्योतः) अनन्तरतमः। उकारादिः॥ नहीति। अबाधेनोपपत्तौ बाधो न युक्त इति भावः॥ घ्यन्तत्वात्पूर्वनिपातबाध इति न युक्तं प्रागुक्तयुक्तेरत आह—लिङ्गद्वयेनेति॥

(दीर्घादिषु ह्रस्वसंज्ञावारणाधिकरणम्)

(आक्षेपवार्तिकशेषभाष्यम्)

भवेद् व्यवस्था च प्रक्लृप्ता॥

(६१८ आक्षेपवार्तिकम्॥ ४॥)

॥*॥ **दीर्घप्लुतयोस्तु पूर्वसंज्ञाप्रसङ्गः** ॥*॥

(भाष्यम्) दीर्घप्लुतयोरपि पूर्वसंज्ञा प्राप्नोति॥ का?॥ ह्रस्वसंज्ञा॥ किं कारणम्?॥ अण् सवर्णान् गृह्णातीति॥

(प्रदीपः) दीर्घप्लुतयोस्त्विति। उकारोण्त्वाद्द्विमात्रत्रिमात्रयोः स्वरूपस्य च ग्राहक इति ह्रस्वसंज्ञा त्रयाणामपि प्राप्नोति। न च दीर्घप्लुतसंज्ञाभ्यां द्विमात्रत्रिमात्रयोर्ह्रस्वसंज्ञा बाध्यते। संज्ञानां समावेशाभ्युपगमात् "आकडारादेका संज्ञा" इति वचनात्। द्विमात्रत्रिमात्रौ त्वनण्त्वाद्भिन्नकालानां न ग्राहकाविति न तत्र दोषः॥

(उद्द्योतः) अणत्वादिति। इदं जातिपक्षस्याप्युपलक्षणम्॥ ननु ह्रस्वसंज्ञावद्दीर्घप्लुतसंज्ञे अपि त्रयाणां स्यातामिति संज्ञात्रयकरणं व्यर्थमत आह—द्विमात्रेत्यादि॥ अनण्त्वादिति। यत्राधिक्येन व्यापकजातिविवक्षणाचेत्यपि बोध्यम्॥ नन्वेवं पदानां संज्ञिनाय-थासंख्यभङ्ग इति चेन्न। शब्दसाम्येनादोषात्॥

(६१९ समाधानवार्तिकम्॥ ५॥)

॥*॥ **सिद्धं तु तपरनिर्देशात्** ॥*॥

(भाष्यम्) सिद्धमेतत्॥ कथम्?॥ तपरनिर्देशः कर्तव्यः—'उदूकाल' इति॥

(आक्षेपभाष्यम्)

यद्येवं

(६२० आक्षेपवार्तिकम्॥ ६॥)

॥*॥ **द्रुतायां तपरकरणे मध्यमविलम्बितयोरुपसंख्यानं कालभेदात्** ॥*॥

(भाष्यम्) [द्रुतायां तपरकरणे मध्यमविलम्बितयोरुपसंख्यानं कर्तव्यम्। तथा मध्यमायां तपरकरणे द्रुतविलम्बितयोरुपसंख्यानं कर्तव्यम्। तथा विलम्बितायां तपरकरणे द्रुतमध्यमयोरुपसं-

स्थानं कर्तव्यम् । किं पुनः कारणं न सिध्यति ? कालभेदात् । ये हि द्रुतायां वृत्तौ वर्णास्त्रिभागाधिकास्ते मध्यमायाम् ये मध्यमायां वर्णास्त्रिभागाधिकास्ते विलम्बितायाम् ॥]

(६२१ समाधानवार्तिकम् ॥ ७ ॥)

॥ * ॥ द्रुतादिषु चोक्तम् ॥ * ॥

(भाष्यम्) **किमुक्तम् ? ॥ *सिद्धं त्ववस्थिता वर्णा वक्तुश्चिराचिरवचनाद् वृत्तयो विशिष्यन्ते* इति ॥**

(उद्द्योतः) भाष्ये—सिद्धं त्ववस्थिता इति । द्रुतत्वादयोभिव्यक्तिगता एवेति भावः ॥

(आक्षेपभाष्यम्)

स तर्हि तपरनिर्देशः कर्तव्यः ॥

(समाधानभाष्यम्)

न कर्तव्यः । इह कालग्रहणं क्रियते । यावच्च तपरकरणं तावच्च कालग्रहणम् । प्रत्येकं च कालशब्दः परिसमाप्यते—उकाल ऊकाल ऊ३काल इति ।

(प्रदीपः) यावच्चेति । एककार्यत्वादेतदुक्तम् । ऊ अजित्येव कालार्थो लभ्यते उकारादयो ह्यच्त्वं न व्यभिचरन्तीति नाच्त्वेन ते विशेष्यन्ते अपि तु तैरच् । तत्रोकारादिकालत्वादुकारादिसदृशोऽज् ग्रहीष्यत इति नार्थः कालग्रहणेन । तत्क्रियते श्रूयमाणेनैवोकारेण कालं विशेषयितुमिति सवर्णग्रहणं न भविष्यति । तत्रैतत्स्यात् ॥ उकारात्परः कालशब्दो न श्रूयत इत्याह—प्रत्येकं चेति । षण्मात्रस्याचोऽसंभवात्संज्ञात्रयकरणाच्चेति भावः ॥

(उद्द्योतः) ननु तपरस्तत्कालस्येतिवत् कालपरस्तत्कालस्येतिसूत्राभावात्कथं समत्वमत आह—एकेति ॥ तदेवोपपादयति—ऊअजिति । किं चैवमुकाराणामेव संज्ञित्वेन संज्ञाविधानवैयर्थ्यापत्तिः ॥ अपि तु तैरजिति । तत्र च मुख्यसामानाधिकरण्ये उक्तदोषाल्लक्षणया सामानाधिकरण्यं दर्शयति—तत्रेति । तत्र सादृश्यान्तरासम्भवाद्व्याख्यानाच्च कालकृतस्यैव तस्य ग्रहणमिति भावः ॥

(समाधानान्तरभाष्यम्)

अथ वा एकसंज्ञाधिकारेऽयं योगः कर्तव्यः । तत्रैका संज्ञा भविष्यति या परा अनवकाशा चेति एवं हि दीर्घप्लुतयोः पूर्वसंज्ञा न भविष्यति ॥

अथ वा "स्वं रूपं शब्दस्याशब्दसंज्ञा" इत्ययं योगः प्रत्याख्यायते । तत्र यदेतद् 'अशब्दसंज्ञा' इति, यया विभक्त्या निर्दिश्यमानमर्थवद्भवति तया निर्दिष्टमुत्तरत्रानुवर्तिष्यते "अणुदित्सवर्णस्य चाप्रत्ययः" अशब्दसंज्ञायामिति ।

(प्रदीपः) **अशब्दसंज्ञायामिति** । ह्रस्वसंज्ञा च शब्दसंज्ञेति तद्विधाने उकारः सवर्णान्न ग्रहीष्यति । उदात्तादयस्तु गुणा न भेदका इति तद्भिन्नस्यापि ह्रस्वसंज्ञा भविष्यति । उदात्तादिसंज्ञास्वज्ग्रहणं निवृत्तमिति दीर्घप्लुतानामपि ता भविष्यन्ति । हलां त्वयोग्यत्वात्तदभावः । **इको यणचीति** तु न शब्दसंज्ञाविधानम् अपि तु **आदिरन्त्येनेति**विहितसंज्ञानुवाद इति सवर्णग्रहणं भविष्यति ॥

(उद्द्योतः) हलां त्विति । शिक्षादावचामेव स्वरकथनादिति भावः ॥ प्रत्याहारेषु जातिपक्षाश्रयणान्न दोष इति तात्पर्यम् ॥

(समाधानान्तरभाष्यम्)

अथ वा ह्रस्वसंज्ञावचनसामर्थ्याद्दीर्घप्लुतयोः पूर्वसंज्ञा न भविष्यति ॥

(प्रदीपः) **अथ वा ह्रस्वसंज्ञेति** । त्रयाणां चेद्ध्रस्वसंज्ञा, तदा ह्रस्वप्रदेशेषु त्रयः संज्ञिन उपतिष्ठन्ते तत्रान्तरतमादेशविधाने ह्रस्वसंज्ञाविधानमनर्थकमेव स्यात् । अथ वचनादनन्तरतमो भवेत् । एवमपि ह्रस्वप्रदेशेष्वज्ग्रहणमेव कुर्यादित्यर्थः ॥

(उद्द्योतः) ननु ह्रस्वसंज्ञा ह्रस्वविधायकेषु एकमात्रादीनां त्रयाणामपि ग्रहणार्थो स्यादित्यत आह—त्रयाणां चेदिति । अन्तरतमेति । प्रमाणत इति शेषः ॥ **ह्रस्वप्रदेशेष्वज्ग्रहणमिति** । न च विधौ ह्रस्वग्रहणे त्रयाणां विधानम् अज्ग्रहणे त्वेकस्यैव विधीयमानत्वेनासवर्णग्राहकत्वादिति विशेष इति वाच्यम् । विधीयमानेनापि कश्चित्सवर्णग्रहणादित्यभिमानः ॥ अनुवादे तूभाभ्यामपि त्रयाणां ग्रहणेनाज्ग्रहणमेव कार्यमिति भावः ॥

(आक्षेपभाष्यम्)

ननु चेदं प्रयोजनं स्यात्—संज्ञया विधाने नियमं वक्ष्यामीति ह्रस्वसंज्ञया यदुच्यते तदचः स्थाने यथा स्यादिति ॥

(उद्द्योतः) भाष्ये ननु चेदमिति ह्रस्वप्रदेशेष्वज्ग्रहणे त्वचश्चेति नियमाभावाद्धलामप्यादेशः प्राप्नोतीति भावः ॥

(समाधानभाष्यम्)

स्यादेतत्प्रयोजनं यदि किंचित्कराणि ह्रस्वशासनानि स्युः । यतस्तु खलु यावदज्ग्रहणं तावद् ह्रस्वग्रहणमतोऽकिंचित्कराणि ह्रस्वशासनानि ।

(उद्द्योतः) परिहरति—स्यादेतदिति । **किञ्चित्कराणि** । किञ्चिद्विशेषकराणि । न चास्ति कश्चिद् ह्रस्वविधाने विशेषः । अन्तरतमपरिभाषया मात्रिकस्थाने मात्रिकस्य द्विमात्रिकस्थाने द्विमात्रिकस्यैव विधानादिति भावः । न चानन्तरतमादेशविधानार्थम् । तद्बाधकल्पनापेक्षयेष्टानुरोधेन तयोर्ह्रस्वसंज्ञाभावज्ञापनस्यैवौचित्यमिति भावः ॥ **यावदज्ग्रहणमिति** । प्रयोगे यत्परिमाणकाज्उच्चारणमित्यर्थः ॥ **तावद् ह्रस्वग्रहणमिति** । तत्परिमाणकस्यैव स्व   ाब्देन ग्रहणं विधानमतस्तानि व्यर्थान्येवेत्यर्थः ॥

ये तु ह्रस्वविधायकेष्वज्ग्रहणमेव कार्यमित्येतद्भाष्याशयं वर्णयन्ति । तेषां संज्ञया विधाने नियममित्यादेः समाधिरयं कथमिति चिन्त्यम् । षड्ग्रहणान्यष्टौग्रहणानीतिभाष्यस्य चोपपत्तिश्चिन्त्येति दिक् ॥ अनुवादे तु ह्रस्वग्रहणाज्ग्रहणयोः समतैवेति एतदर्थद्वयबोधनार्थमेवेहश्लिष्टशब्दोपादानं भाष्ये इति बोध्यम् ॥

(समाधानबाधकप्रयोजनान्तरभाष्यम्)

इदं तर्हि प्रयोजनम्—"एच इग् ह्रस्वादेशे" इति वक्ष्यामीति । अनुच्यमाने ह्येतस्मिंस्त्रिर्ह्रस्वप्रदेशेष्वेच इग्भवतीति वक्तव्यं स्यात् । "ह्रस्वो नपुंसके प्रातिपदिकस्य" एच इग्भवतीति । "णौ चङ्युपधाया ह्रस्वः" एच इग्भवतीति । "ह्रस्वः [हलादिः शेषः]" एच इग्भवतीति ॥ संज्ञा च नाम यतो न लघीयः ॥ कुत एतत् ? ॥ लघ्वर्थं हि संज्ञाकरणम् ॥

(प्रदीपः) इदं तर्हीति । असत्यां ह्रस्वसंज्ञायां ह्रस्वादेश इति कर्तुं न युज्यते । ततश्च ह्रस्वविधिप्रदेशेषु बहुकृत्व एच इगिति वक्तव्यं तद्गुरु भवति ॥

(समाधानसाधकभाष्यम्)

लघीयश्च त्रिर्ह्रस्वप्रदेशेष्वेच इग्भवतीति, न पुनः संज्ञाकरणम् । त्रिर्ह्रस्वप्रदेशेषु एच इग्भवतीति षड् ग्रहणानि । संज्ञाकरणे पुनरष्टौ—ह्रस्वसंज्ञा वक्तव्या, त्रिर्ह्रस्वप्रदेशेषु ह्रस्वग्रहणं कर्तव्यं ह्रस्वो ह्रस्वो ह्रस्व इति, एच इग्घ्रस्वादेश इति । सोयमेवं लघीयसा न्यासेन सिद्धे सति यद्गरीयांसं यत्नमारभते तस्यैतत्प्रयोजनं दीर्घप्लुतयोस्तु पूर्वसंज्ञा मा भूदिति ॥ ऊकालोऽज्झ्रस्व० ॥ २७ ॥

(प्रदीपः) ग्रहणानीति । गृह्यतेनेनार्थ इति ग्रहणं पदमुच्यते । ह्रस्वादेश इत्याङः प्रश्लेषनिर्देशात्पृथक्प्रयोगाभावाद्भिन्न गणितः ॥ ननु मितां ह्रस्व इत्यत्र हेड वेष्टन इत्यस्य ह्रियतीत्यर्थमेचइगितिवक्तव्यम् । तथा खित्यनव्ययस्येत्यत्रापि परमतुंमन्य इत्यर्थमिति गौरवप्रसङ्गः । एवं तर्ह्येच इगिति पक्षकृत्वोप्युच्चार्यमाणे प्रतिपत्तिलाघवं भवतीति लाघवोपलक्षणपरं भाष्यं द्रष्टव्यम् ॥ ह्रस्वदीर्घप्लुत इति सौत्रत्वान्निर्देशस्य लिङ्गव्यत्ययेन पुंस्त्वम् ॥ २७ ॥

(उद्द्योतः) लाघवोपलक्षणपरमिति । केचित्तु एतत्सूत्रस्यैतद्भाष्यप्रमाण्यात् कमेर्णिङिति सूत्रे चिण्णमुलोरिति सूत्रस्य दीर्घग्रहणस्यैतदिदानीं प्रयोजनं यद्दीर्घविधौ स्थानिवत्त्वनिषेध इति वदतो भाष्यकारस्य प्रामाण्याच्च चिण्णमुलोरिति सूत्रस्थभाष्याच्च हेड वेष्टन इति धातोर्घटादावसांप्रदायिकः पाठः । परमनुंमन्य इत्यादेश्चैतद्भाष्यप्रामाण्यादनभिधानमिति यथाश्रुतं भाष्यमेव सम्यगित्याहुः ॥ पुंलिङ्गैकवचनदर्शनाद् द्वन्द्वानुपपत्तिमाशङ्कयाह—सौत्रत्वादिति । लिङ्गस्य लौकिकत्वात्तद्व्यत्यय नचितो न तु शास्त्रीयैकवचनस्येति भावः ॥ २७ ॥

———>o<———

(८४ अच्परिभाषासूत्रम् ॥ १ । २ । १ आ० १६ सूत्रम्)

१०२ अचश्च ॥ १ । २ । २८ ॥

(आक्षेपभाष्यम्)

किमयमलोन्त्यशेष आहोस्विदलोन्त्यापवादः? ॥

(आक्षेपसाधकहेतुजिज्ञासाभाष्यम्)

कथं वायं तच्छेषः स्यात् कथं वा तदपवादः? ॥

(आक्षेपसाधकभाष्यम्)

यद्येकं वाक्यं तच्चेदं च—अलोन्त्यस्य विधयो भवन्त्यचो ह्रस्वदीर्घप्लुता अन्त्यस्येति, ततोयं तच्छेषः। अथ नानावाक्यमलोन्त्यस्य विधयो भवन्ति । अचो ह्रस्वदीर्घप्लुता अन्त्यस्यानन्त्यस्य चेति, ततोयं तदपवादः ॥

(प्रदीपः) अचश्च ॥ २८ ॥ इको गुणवृद्धी इत्यनेन समानमिदम् ॥

(उद्द्योतः) अचश्च ॥ २८ ॥ भाष्येऽलोन्त्यस्य विधयो भवन्तीत्यनेन तस्य व्यापकत्वं बोधितं तेनैतत्प्रवृत्त्यभावेपि स्थानषष्ठीरूपाल्लिङ्गाद्विव उदित्यादावलोन्त्यस्येत्यस्य प्रवृत्तिः सूचिता ॥ एकवाक्यतां दर्शयति—अच इति ॥

(विशेषजिज्ञासाक्षेपभाष्यम्)

कश्चात्र विशेषः ? ।

(६२२ तच्छेषपक्षदूषणाक्षेपवार्तिकम् ॥ १ ॥)

॥*॥ ह्रस्वादिविधिरलोन्त्यस्येति चेद्वचिप्रच्छिशमादिप्रभृतिहनिगमिदीर्घेष्वज्ग्रहणम् ॥ * ॥

(भाष्यम्) ह्रस्वादिविधिरलोन्त्यस्येति चेद्वचिप्रच्छिशमादिप्रभृतिहनिगमिदीर्घेष्वज्ग्रहणं कर्तव्यम् । वचिपृच्छ्योर्दीर्घः 'अचः' इति वक्तव्यम् । अनन्त्यत्वाद्धि न प्राप्नोति ॥ शमादीनां दीर्घः 'अच' इति वक्तव्यम् । अनन्त्यत्वाद्धि न प्राप्नोति ॥ हनिगम्योर्दीर्घः 'अच' इति वक्तव्यम् । अनन्त्यत्वाद्धि न प्राप्नोति ॥

(प्रदीपः) शमादिप्रभृतीति । प्रभृतिग्रहणेन ष्ठिवुक्लम्वादयो गृह्यन्ते ॥

(उद्द्योतः) आदिप्रभृतिशब्दयोः पौनरुक्त्यं परिहरति— प्रभृतीति । आदिपदं तु शमामष्टानामिति सूत्रस्थबहुवचनानुवादकमिति भावः ॥

(तदपवादपक्षाभ्युपगमभाष्यम्)

अस्तु तर्हि तदपवादः ।

(६२३ तदपवादपक्षदूषणाक्षेपवार्तिकम् ॥ २ ॥)

॥ * ॥ अचश्चेन्नपुंसकह्रस्वाकृत्सार्वधातुकनामिदीर्घेष्वनन्त्यप्रतिषेधः ॥ * ॥

(भाष्यम्) अचश्चेन्नपुंसकह्रस्वाकृत्सार्वधातुकनामिदीर्घेष्वनन्त्यस्य प्रतिषेधो वक्तव्यः "ह्रस्वो नपुंसके प्रातिपदिकस्य" यथेह भवति—रै अतिरि, नौ अतिनु । एवं सुवाक् ब्राह्मणकुलमित्यत्रापि प्राप्नोति ॥ "अकृत्सार्वधातुकयोर्दीर्घः" यथेह भवति—चीयते स्तूयते । एवं छिद्यते भिद्यते अत्रापि प्राप्नोति ॥ "नामि" दीर्घः यथेह भवति अग्नीनाम् वायूनाम् । एवं षण्णामित्यत्रापि प्राप्नोति ।

(आक्षेपबाधकभाष्यम्)

नैष दोषः । "नोपधायाः" इत्येतन्नियमार्थं भविष्यति ॥

(आक्षेपसाधकभाष्यम्)

प्रकृतस्यैष नियमः स्यात् ॥ किं च प्रकृतम् ? । "नामि" इति । तेन भवेदिह नियमान्न स्यात् षण्णामिति । अन्यते तन्यत इत्यत्रापि प्राप्नोति ॥

अथाप्येवं नियमः स्यात्-नोपधाया नाम्येवेति । एवमपि भवेदिह नियमान्न स्यात्-अन्यते तन्यत इति । षण्णामित्यत्र प्राप्नोति ॥

अथाप्युभयतोऽयं नियमः स्यात्—नोपधाया एव नामि, नाम्येव नोपधाया इति । एवमपि भिद्यते छिद्यते सुवाक् ब्राह्मणकुलमित्यत्रापि प्राप्नोति ॥

(प्रदीपः) भिद्यत इति । यकारादौ यदङ्गं तस्य योऽवयवोऽजित्येवमत्र प्रसङ्गः । यदा त्वजेव यकारादिना विशेष्यते, तदात्र व्यवधानान्नास्ति प्रसङ्गः एवमन्यत्रापि ज्ञेयम् ॥

(उद्द्योतः) यदा त्विति । इदं चिन्त्यं, प्रत्ययस्याङ्गाक्षेपोत्थिताकाङ्क्षत्वात् ॥

(पदोपस्थितिपक्षस्थापनभाष्यम्)

एवं तर्हि ह्रस्वो दीर्घः प्लुत इति यत्र ब्रूयात्, 'अचः' इत्येतत्तत्रोपस्थितं द्रष्टव्यम् ॥ किं कृतं भवति ? । द्वितीया षष्ठी प्रादुर्भाव्यते । तत्र कामचारः—गृह्यमाणेन वाऽचं विशेषयितुमचा वा गृह्यमाणम् ॥ यावता कामचारः । इह तावद्यचिप्रच्छिशमादिप्रभृतिहनिगमिदीर्घेषु गृह्यमाणेनाचं विशेषयिष्यामः । एतेषां दीर्घो भवति अच इति । इहेदानीं नपुंसकह्रस्वाकृत्सार्वधातुकनामिदीर्घेष्वचा गृह्यमाणं विशेषयिष्यामः । नपुंसकस्य ह्रस्वो भवति, अचः अजन्तस्येति । अकृत्सार्वधातुकयोर्दीर्घो भवति, अचः अजन्तस्येति । नामि दीर्घो भवति 'अचः' अजन्तस्येति ॥

(परिभाषोपस्थापकलिङ्गाधिकरणम्)

(आक्षेपभाष्यम्)

इह कस्मान्न भवति द्यौः पन्थाः स इति ।

(६२४ समाधानवार्तिकम् ॥ ३ ॥)

॥ * ॥ संज्ञया विधाने नियमः ॥ * ॥

(भाष्यम्) संज्ञया ये विधीयन्ते तेषु नियमः ॥

किं वक्तव्यमेतत् ? ॥

नहि ॥

कथमनुच्यमानं गंस्यते ? ॥

अजिति हि वर्तते । तत्रैवमभिसंबन्धः करिष्यते—अचः अज्भवति ह्रस्वो दीर्घः प्लुत इत्येवं भाव्यमान इति ॥

(प्रदीपः) अजिति हि वर्तत इति । ततश्च ह्रस्वादिशब्दा इहानुवृत्ता नाचमुपस्थापयन्ति तस्य स्वयमुपस्थानादित्याश्रितस्वरूपव्यापारा आश्रीयन्ते तेन ह्रस्व इत्येवं योऽच् सोऽचः स्थाने भवतीत्यर्थः संपद्यते । एवं दीर्घप्लुतयोरपि ॥

(उद्द्योतः) नाचमिति । ह्रस्वादिसंज्ञका अचोऽचः स्थाने इति नायं इति भावः ॥ स्वयमिति । अच्पदेनैवेत्यर्थः ॥ आश्रितः स्वरूपस्य शब्दस्य व्यापारो यैरित्यर्थस्तदाह—ह्रस्व इत्येवमिति ॥

(आक्षेपभाष्यम्)

अथ पूर्वस्मिन् योगे अज्ग्रहणे सति किं प्रयोजनम् ? ॥

(प्रदीपः) अथेति । इहैव तदज्ग्रहणं क्रियतां पूर्वसूत्रे तु न वक्तव्यमिति प्रश्नः ॥

(६२५ समाधानवार्तिकम् ॥ ४ ॥)

॥ * ॥ अज्ग्रहणं संयोगाच्समुदायनिवृत्त्यर्थम् ॥ * ॥

(भाष्यम्) अज्ग्रहणं क्रियते संयोगनिवृत्त्यर्थम् । अच्समुदायनिवृत्त्यर्थं च । संयोगनिवृत्त्यर्थं तावत्—प्रतक्ष्य प्ररक्ष्य "ह्रस्वस्य पिति कृति तुक्" इति तुङ्मा भूदिति । अच्समुदायनिवृत्त्यर्थं तितउच्छत्रं तितउच्छाया "दीर्घात्पदान्ताद्वा" इति विभाषा तुङ्मा भूदिति ॥ अचश्च ॥ २८ ॥

(प्रदीपः) प्रतक्ष्येति । यथा प्रत्याहारे अश्रुता आका-

रादयो दीर्घप्लुतसंज्ञे लभन्ते तथा संयोगोपि ह्रस्वसंज्ञः स्यादिति तुक्प्रसङ्गः ॥ तितउच्छत्रमिति । परत्वाद्दीर्घलक्षणे वा तुकि सति सकृद्गतौ विप्रतिषेध इति न्यायाद् ह्रस्वलक्षणः पुनर्न प्रवर्तते। नचैवंविधे विषये पुनः प्रसङ्गविज्ञानमस्ति। नित्यविकल्पयोर्विरोधात्। पूर्वेण परस्य बाधप्रसङ्गात् । यत्र हि पूर्वो विधिः परं न बाधते तत्र पुनः प्रसङ्गविज्ञानं क्वचिदाश्रीयते । समुदाये वा कार्ये प्रति व्याप्रियमाणे अवयवानां पारतन्त्र्यादव्यापारान्नैव ह्रस्वलक्षणतुक्प्रसङ्गः ॥ ननु क्रियमाणेऽप्यज्ग्रहणे वर्णग्रहणे जातिग्रहणादच्समुदायस्यापि दीर्घसंज्ञाप्रसङ्गः ॥ नैष दोषः । ऊकाल इति विशेषणादिह व्यक्तिराश्रीयते । नहि जातेः परिमाणमस्ति । व्यक्तिद्वारकं वा जातेः परिमाणमाश्रीयते । एकैकव्यक्तिव्यङ्ग्या हि जातिर्न समुदायव्यङ्ग्या ॥ २८ ॥

(उद्द्योतः) ननु मात्रिकाणां हलामुपदेशाभावादसत्त्वेन संज्ञाभावमाशङ्क्याह—यथेति ॥ वा तुकीति । वैकल्पिके तुकीति यावत् ॥ विरोधादिति । तथा च विकल्पविधिप्रवृत्तेर्वैयर्थ्यापत्त्या नित्यस्य बाध एवेत्यर्थः ॥ क तर्हि पुनः प्रसङ्गविज्ञानं, तत्राह—यत्र हीति । यथा भिन्धकीत्यत्र परत्वाद्धौ कृते पुनः प्रसङ्गविज्ञानादकच् । न हि तत्राकच्–धिप्रवृत्त्योर्विरोधः ॥ समुदाये चेति । इदं चिन्त्यम् । बहुशो दृष्टत्वात् । व्यक्तिद्वारकपरिमाणसम्भवं प्रकृते आह—एकैवेति । द्विमात्राकालकव्यक्तिगताच्त्वजातिर्दीर्घ इति अर्थः स्यात्। तत्र या व्यक्तिः प्रत्येकरूपा न सा द्विमात्राकाला या च तादृशी न सा व्यक्तिरिति भावः । हलन्ताच्चेत्यादौ तु इक्समीपव्यक्तिवृत्तिहल्त्वजातेः पर इत्यर्थान्न धिप्सतीत्यादौ दोषः । जातेर्हि जात्यन्तरं व्यवधायकमिति न सजातीयद्वितीयव्यक्तिर्व्यवधायिकेति बोध्यम् ॥ परे तु वर्णाद्वर्णान्तरोच्चारणेऽर्धमात्राकालस्य सत्त्वेन वर्णसमुदाये मात्राकालिकत्वासम्भव इति प्रश्नो भाष्ये—अथ पूर्वेति ॥ उत्तरं तु तावत्सूक्ष्मकालग्रहणासमर्थस्य तत्र संज्ञाप्रवृत्तिशङ्कावारणार्थमित्याशयेन । एवं च जातिग्रहणमित्यस्य जात्याश्रयानेकव्यक्तिग्रहणमित्यर्थेपि न दोषः ॥ मात्राकालोवग्रहोऽर्धमात्राकालोवग्रह इति प्रातिशाख्ययोरविरोधाय परः सन्निकर्ष इति सूत्रस्य भाष्येण च वर्णाद्वर्णान्तरोच्चारणेऽर्धमात्राकालव्यवायस्यावश्यकत्वादित्याहुः ॥ २८ ॥

(४५-४६उदात्तानुदात्तसंज्ञासूत्रे ॥१।२।१ आ.१७. १८)

१०३ उच्चैरुदात्तः ॥ १ । २ । २९ ॥

१०४ नीचैरनुदात्तः । १ । २ । ३० ॥

(षष्ठीनिर्दिष्टाज्ग्रहणानुवृत्तिविचाराधिकरणम्)

(आक्षेपभाष्यम्)

किं षष्ठीनिर्दिष्टमज्ग्रहणमनुवर्तते । उताहो न?॥

(प्रदीपः) उच्चैः ॥ २९ ॥ षष्ठीनिर्दिष्टमिति । उच्चैर्नीचैरित्येते अव्यये अधिकरणशक्तिप्रधाने । तत्राच इत्यनुवृत्तौ सत्यामयमर्थो भवति—उच्चैः स्थान उपलभ्यमान उदात्तसंज्ञः स चाचः स्थान इति ॥

(उद्द्योतः) उच्चैरुदात्तः ॥ २९ ॥ नन्वच इत्यनुवृत्तावपि कथं परिभाषाऽप्रक्लृप्तिरनुवृत्तस्य प्रकृतसूत्रेष्वपेक्षितसंज्ञिसमर्पकत्वेपि स्वरोऽच एव स्थाने इत्यर्थकत्वे मानाभावादत आह—उच्चैरिति । संज्ञिसमर्पणस्य प्रथमान्तानुवृत्त्यापि सिद्धेरिति भावः ॥ स्थाने । ताल्वादौ । उच्चै, उच्चदेशे, उपलभ्यमान इत्यन्वयः । उपलभ्यमानः, व्यज्यमानः ॥ स चाच इति । वाक्यभेदेन षष्ठ्यन्ताच्पदेन सम्बन्ध इति भावः ॥

(विशेषजिज्ञासाभाष्यम्)

किं चातः ? ॥

(विशेषप्रतिपादनभाष्यम्)

यद्यनुवर्तते "हल्स्वरप्राप्तौ व्यञ्जनमविद्यमानवद्भवति" इत्येषा परिभाषा न प्रकल्पते । कथं हलो नाम स्वरप्राप्तिः स्यात् ॥ एवं तर्हि निवृत्तम् । बह्न्येतस्याः परिभाषायाः प्रयोजनानि ॥

(प्रदीपः) हल्स्वरप्राप्ताविति । सत्यामच इत्यस्यानुवृत्तौ समासस्येत्यन्तोदात्तत्वं राजपुरुष इत्यादावेव स्याद् न तु राजदृषदित्यादौ षकाराकारस्य । असत्यां त्वनुवृत्तौ समासस्य योन्तो दकारस्तस्य स्वरप्राप्तावविद्यमानत्वादकारस्य स्वरः सिध्यति। एषा च परिभाषा यतोऽनाव इत्यत्रानाव इति प्रतिषेधेन ज्ञापिता। अन्यथा नाव्यमित्यत्र नकारस्यायोग्यत्वादाकारस्य चानादित्वादुदात्तत्वं न भविष्यतीति किमनाव इति प्रतिषेधेन॥

(उद्द्योतः) नन्वच्ग्रहणानुवृत्त्यैव सिद्धे मास्तु परिभाषाप्रवृत्तिरत आह—सत्यामिति । समासस्येत्यत्राच इत्यस्योपस्थित्या तेन समासे विशेष्यमाणे राजदृषदित्यादौ न स्यादित्यर्थः ॥ षकाराकारस्येति । तथा च तत्सिद्ध्यर्थं परिभाषैव कर्तव्या नाच इत्यनुवृत्तिरिति भावः । तदाह—भाष्ये—बह्न्येतस्या इति । यतो नाव इति । यदन्तस्य ञ्नित्कस्यादिरुदात्त इति तदर्थः ॥

(इति षष्ठीनिर्दिष्टाज्ग्रहणाननुवृत्तिनिर्णयः)

(अथ प्रथमानिर्दिष्टाज्ग्रहणानुवृत्तिविचाराधिकरणम्)

(आक्षेपभाष्यम्)

अथ प्रथमानिर्दिष्टमज्ग्रहणमनुवर्तते । उताहो न ॥

(प्रदीपः) अथ प्रथमानिर्दिष्टमिति ॥ ननु को विशेषः यावता यत्र स्वरो विधीयते तत्र व्यञ्जनस्याविद्यमानत्वादच एव भविष्यति । अनुदात्तादेरञ्जित्यादावनुवादेपि न दोषः । स्वत एव हलोऽनुदात्तत्वं भवतु, अजुपरागवशाद्वा, तदनुवादेन कार्यविधाने न कश्चिद्विशेषः। एवं तर्हि न्यायव्युत्पादनार्थ एवायं विचारः ॥

(उद्योतः) यावतेति । न चाचः स्थाने प्लुत्युदात्तादिशब्देन प्रत्यायितः स्यादिति वाच्यम् । अन्तरतमपरिभाषयाऽप्राप्तेः ॥ ननु स्वरशेषाया अविद्यमानवत्परिभाषाया अन्यत्राप्राप्तेस्तत्र दोषोऽत आह—अनुदात्तादेरिति । स्वत एवेत्यस्याचां त्रैस्वर्यवत्तेषामनुदात्तत्वमेवेति विशेषस्वराप्राप्त्या स्वरवर एवावतिष्ठत इत्यर्थः ॥ ननु स्वतस्तथात्वकल्पने मानाभावः । किंचोदात्तसमवधानेऽप्यनुदात्तत्वप्रतीत्यापत्तिरेवेत्यत आह—अनुपेति ॥ न्यायेति । उदात्तत्वादीनामज्धर्मत्वविषयकन्यायेत्यर्थः ॥

(जिज्ञासाभाष्यम्)

किं चार्थोऽनुवृत्त्या ? ॥

(उद्योतः) भाष्येऽनुवृत्तेः प्रयोजनाभावात्सन्देहानुपपत्तिरिति पृच्छति—किश्चेति । अनुवृत्तेर्न फलमित्यर्थः ॥

(प्रयोजननिरासभाष्यम्)

बाढमर्थः । यद्येते व्यञ्जनस्यापि गुणा लक्ष्यन्ते ॥

(उद्योतः) भाष्ये यदि लक्ष्यन्ते तदार्थः, यतो न लक्ष्यन्तेऽतो नार्थ इत्यन्वयः ॥

(प्रयोजनसाधकभाष्यम्)

ननु च प्रत्यक्षमुपलभ्यन्ते—इषे त्वोर्जे त्वा ॥

(प्रदीपः) ननु चेति । बाधकाभावाच्च भ्रान्त्यसिद्धिः ॥

(उद्योतः) नन्वियं प्रतीती रक्तस्फटिकप्रतीतिवद् भ्रान्तेत्यत आह—बाधकेति ॥

(प्रयोजननिरासभाष्यम्)

नैते व्यञ्जनस्य गुणाः, किं त्वच एव । तत्सामीप्यात्तु व्यञ्जनमपि तद्गुणमुपलभ्यते । तद्यथा—द्वयो रक्तयोर्वस्त्रयोर्मध्ये शुक्लं वस्त्रं तद्गुणमुपलभ्यते । बदरपिटके रिक्तको लोहकंसस्तद्गुण उपलभ्यते ॥

(प्रदीपः) नैते इति । अन्यथाऽप्युपलम्भोपपत्तेरिति भावः ॥

(उद्योतः) प्रतीतिर्भ्रान्तैवेत्याह—नैते इति । भाष्ये ॥ तद्याचष्टे—अन्यथापीति । रिक्तको लोहकंसः, आदर्शः । रिक्तकः घर्षणेन उज्ज्वलीकृतः बदरपिटके बदरफलयुक्तपेटिकेति संप्रदायः ॥

(प्रयोजनसाधकभाष्यम्)

कुतो नु खल्वेतत्—अच एते गुणाः स्युः तत्सामीप्यात्तु व्यञ्जनमपि तद्गुणमुपलभ्यते । न पुनर्व्यञ्जनस्यैते गुणाः स्युस्तत्सामीप्यादजपि तद्गुण उपलभ्येतेति ? ॥

(उद्योतः) प्रतीतेर्भ्रान्तत्वे बीजं पृच्छति—कुतो न्विति ॥

(प्रयोजननिराकरणभाष्यम्)

अन्तरेणापि व्यञ्जनमच एवैते गुणा लक्ष्यन्ते, न पुनरन्तरेणाचं व्यञ्जनस्योच्चारणमपि भवति । अन्वर्थं खल्वपि निर्वचनम्—स्वयं राजन्त इति स्वराः, अन्वग्भवति व्यञ्जनमिति ॥

(प्रदीपः) अन्तरेणापि व्यञ्जनमिति । आप्यायध्वमिति यथा । अत्र ह्याकार उदात्तः, तिङन्तस्य निघातः । ततश्चान्वयव्यतिरेकाभ्यामच एवैते गुणाः । यदि तु हलामप्येते गुणा अभविष्यन् तदा हलामचां च भिन्नस्वरताप्युपालप्स्यत यस्मात्त्वचामेव स्वरमनुविदधति, न हलः । तस्मान्न हलां स्वयं स्वरोऽस्तीति निश्चयः ॥ अन्वग्भवतीति । अनुगच्छतीत्यर्थः । शिष्टसमाचाराच्चेदं निर्वचनमभिहितं, न त्वत्र वर्णसादृश्यं किंचिदस्ति । अथ वा गतिरपि व्यञ्जेरर्थः विविधं गच्छत्युपरागवशादिति व्यञ्जनमित्ययमर्थः पर्यायान्तरेण भाष्यकारेणाभिहितः । उपरागश्च पूर्वपराच्सन्निधानेऽपि परेणाचा हलो भवति न पूर्वेण ॥

(उद्योतः) अजन्वयव्यतिरेकौ बीजमित्याह—अन्तरेणापीति । अत्र हीति ॥ निपाता आद्युदात्ता इति तिङ्ङतिङ इत्याभ्यामिति भावः ॥ न पुनरन्तरेणेति । अन्वयप्रदर्शनमिदं प्रक्रियाप्राप्तातिरिक्तविषयं, सौत्रप्रयोगातिरिक्तविषयकं च बोध्यम् ॥ स्वयं राजन्त इति भाष्यस्योदात्तादिगुणैरित्यर्थः ॥ अनुगच्छतीति । अज्गुणमिति शेषः ॥ नत्वत्र वर्णसादृश्यमिति । निर्वचनं हि तत्तद्धात्वर्थयोगेनार्थाभावेऽपि वर्णसादृश्येन वेत्याशयः ॥ अर्थयोग एवास्तीत्याह—अथवेति ॥ विविधमिति । उदात्तत्वादिरूपनानाप्रकारगमनमजधीनमिति शब्दादेव लभ्यत इति भावः ॥ पर्यायेति । यो हि यमनुगच्छति स तद्वद् विविधं गच्छतीत्यर्थः ॥ ननु विरुद्धस्वरद्वयमध्यगतस्य व्यञ्जनस्य स्वरद्वयाद्युपरागापत्तिरत आह—उपरागश्चेति । स्वभाव एवात्र बीजम् ॥

(इति प्रथमानिर्दिष्टाज्ग्रहणानुवृत्तिनिश्चयः)

(६२६ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ उच्चनीचस्यानवस्थितत्वात्संज्ञाऽप्रसिद्धिः ॥ * ॥

(भाष्यम्) इदमुच्चनीचमनवस्थितपदार्थकम्, तदेव हि कं चित्प्रत्युच्चैर्भवति, कं चित्प्रति नीचैः। एवं हि कश्चित्कं चिदधीयानमाह किमुच्चै रोरूयसे शनैर्वर्ततामिति। तमेव तथाऽधीयानमपर आह किमन्तर्दन्तकेनाधीषे उच्चैर्वर्ततामिति। एवमुच्चनीचमनवस्थितपदार्थकम्, तस्यानवस्थितत्वात् संज्ञाया अप्रसिद्धिः ॥

(प्रदीपः) उच्चनीचस्येति । श्रुतिप्रकर्षापकर्षलक्षणोच्चनीचत्वाश्रयः पर्यनुयोगः । नचानवस्थितधर्मत्वाश्रयेण साधुत्वं व्यवतिष्ठते ॥

(उद्द्योतः) अधिकरणशक्तिप्रधानत्वात्कथमयं पर्यनुयोगोत आह—श्रुतीति । उच्चैः श्रूयमाण उदात्त इत्यादिरर्थ इत्यभिमानः। नन्वस्त्वनवस्थितत्वं को दोषोत आह—नचेति ॥

(आक्षेपबाधकभाष्यम्)

एवं तर्हि लक्षणं करिष्यते—आयामो दारुण्यमणुता खस्येति उच्चैःकराणि शब्दस्य। आयामो गात्राणां निग्रहः । दारुण्यं स्वरस्य दारुणता रूक्षता। अणुता खस्य कण्ठस्य संवृतता। उच्चैः कराणि शब्दस्य ॥ अन्ववसर्गो मार्दवमुरुता खस्येति नीचैःकराणि शब्दस्य । अन्ववसर्गो गात्राणां शिथिलता। मार्दवं स्वरस्य मृदुता स्निग्धता। उरुता खस्य महत्ता कण्ठस्येति नीचैःकराणि शब्दस्य ॥

(उद्द्योतः) भाष्ये—एवं तर्हि लक्षणमिति । न श्रुतिगतप्रकर्षाश्रयमुच्चत्वं नीचत्वं किन्तु ईदृशव्यापकव्याप्यमिति भावः ॥

(आक्षेपसाधकभाष्यम्)

एतदप्यनैकान्तिकम्। यदप्यल्पप्राणस्य सर्वोच्चैस्तन्महाप्राणस्य सर्वनीचैः ॥

(प्रदीपः) एतदपीति। श्रोता हि वक्तृगतानायामादीन्धर्मान्कार्यादवस्यति, कार्यं च संकीर्णम्। तथाहि—महाप्राणो नीचैरप्युच्चारयन्स्वरेण महान्तं देशं व्याप्नोति। अल्पप्राणस्तूच्चैरपि वदन्नल्पं देशं व्याप्नोति ॥

(उद्द्योतः) श्रोता हीति। आयामादीनां श्रुतिप्रकर्षानुमेयत्वात् तस्य चाव्यवस्थितत्वादव्यवस्थितत्वमिति भावः ॥

(६२७ समाधानवार्तिकम् ॥ २ ॥)

॥*॥ सिद्धं तु समानप्रक्रमवचनात् ॥*॥

(भाष्यम्) सिद्धमेतत् ॥ कथम्? ॥ समाने प्रक्रम इति वक्तव्यम् ॥ कः पुनः प्रक्रमः? ॥ उरः कण्ठः शिर इति ॥ उच्चैरुदात्तः ॥ २९ ॥ नीचैरनु० ॥३०॥

(प्रदीपः) सिद्धं त्विति। प्रक्रम्यन्तेऽस्मिन्वर्णा इति प्रक्रमः स्थानमुच्यते। तेनायमर्थः एकस्मिंस्ताल्वादिके स्थाने ऊर्ध्वाधरभागयुक्ते ऊर्ध्वभागेनोच्चार्यमाण उदात्तः, अधरभागनिष्पन्नोऽनुदात्तः। एवं चोच्चैरित्यनेनोर्ध्वभागो गृह्यते नीचैरित्यधरभागः । अभ्याससमधिगम्यश्चायं स्वरविशेषः षड्जादिवद्विज्ञेयः ॥

(उद्द्योतः) प्रक्रम्यन्त इति। अधिकरणे घञि नोदात्तोपदेशस्येति वृद्धिप्रतिषेधः ॥ ऊर्ध्वभागेनेति । ऊर्ध्वभागावच्छिन्नवायुसंयोगेनेत्यर्थः ॥ न चेदमपूर्वं कर्तव्यमित्याह—पूर्वं चेति। करणस्य चाधिकरणत्वविवक्षा बोध्या। कस्योर्ध्वभागे इत्याकाङ्क्षायां योग्यतया स्थानस्येति लभ्यत इति भावः। मन्दं प्रति तु वचनमेवावश्यकमिति बोध्यम् ॥ भाष्ये—उरः कण्ठः शिर इति। शिरःपदं ताल्वादीनामुपलक्षणम् ॥ २९ ॥

—※—

(८७ स्वरितसंज्ञासूत्रम् ॥ १ । २ । १ आ० १९ सू०)

१०५ समाहारः स्वरितः ॥१ । २ ।३१॥

(समाह्रियमाणनिर्णयाधिकरणम्)

(आक्षेपभाष्यम्)

समाहारः स्वरित इत्युच्यते। कस्य समाहारः स्वरितसंज्ञो भवति? ॥

(प्रदीपः) समा ॥३१॥ कस्येति। समाहरणं समाहार इति भावसाधनं मत्वा कस्येति प्रश्नः ॥

(उद्द्योतः) समाहारः ॥ ३१ ॥ समाहारशब्दे कर्मसाधने कस्येति षष्ठ्यन्तेन पृच्छानुपपन्नेत्यत आह—भावेति। जातौ च कस्येत्येकवचनम् ॥

(अच्समाहारस्वीकारेणसमाधानभाष्यम्)

अचोरित्याह ॥

(प्रदीपः) अचोरिति। तयोः समाहार उपश्लेषरूपः। अन्यत्र औत्तराधर्यरूपोपि संभवति। गार्ग्येऽनूपइति स्थानिनोरेकाराकारयोरुदात्तानुदात्तयोः समाहारात् स्थानिधर्मेणादेशस्यापि तथा व्यपदेशः ॥

(उद्द्योतः) उपश्लेषः। अव्यहितोत्तरत्वरूपः। अन्यत्र। पूलाद्वौ। औत्तराधर्यमाधाराधेयभावः। न च वर्णानां सः। अमूर्तत्वादस्थिरत्वाच्चेति भावः ॥ स्वरितभाज एकादेशस्यैकत्वात् कथमत्र द्वयोरचोः समाहारोत आह—स्थानिनोरिति ॥

(६२८ अच्समाहारानुपपत्तिवार्तिकम् ॥ १ ॥)

॥ * ॥ समाहारोऽचोश्चेन्नाभावात् ॥ * ॥

(भाष्यम्) समाहारोचोश्चेत्, तन्न ॥ किं कारणम्? ॥ अभावात्। नह्यचोः समाहारोस्ति ॥

(प्रदीपः) समाहारोचोश्चेदिति । कार्यं क्व कन्या इत्यादौ स्थानिद्वारकोपि समाहारव्यपदेशो नास्ति । यत्राप्यस्ति गाङ्गेऽनूप इति—तत्राप्यसौ गौणः । गाङ्गशब्दो ऽणन्तत्वादन्तोदात्तः । सप्तम्येकवचनेन सुप्त्वादनुदात्तेन सहैकादेश उदात्तः । अनूपशब्दः **अनोरप्रधानकनीयसी** इत्यन्तोदात्तत्वादनुदात्तादिः, तत एकादेशः **स्वरितो वाऽनुदात्ते पदादाविति** स्वरितः ॥

(उद्द्योतः) कार्यकशब्दयोर्ण्यदन्तयोस्तित्वात्स्वरितत्वं कन्येत्यत्र कन्याराजन्यमनुष्याणामन्त इति तत् ॥ एवं च गौणोपि सर्वत्र नास्तीत्यर्थः ॥ गौण इति । स्थानिनोरुपश्लेषस्याशास्त्रीयत्वेन स्थानिवत्सूत्राप्रवृत्तेः, लोकन्यायसिद्धस्तु गौण इत्यर्थः ॥

(अच्समाहारोदाहरणभाष्यम्)

नन्वयमस्ति गाङ्गेऽनूप इति ॥

(अच्समाहारबाधकभाष्यम्)

नैवोचोः समाहारः । अन्योयमुदात्तानुदात्तयोः स्थाने एक आदिश्यते ॥

(गुणसमाहारपक्षाभ्युपगमभाष्यम्)

एवं तर्हि गुणयोः ॥

(प्रदीपः) एवं तर्हीति । गुणयोर्नैरन्तर्येणोपलम्भादस्ति समाहारः ॥

(उद्द्योतः) नन्वचोः समाहाराभावे कथं तद्गुणयोः समाहारोत आह—गुणयोरिति । एकाज्निष्ठयोरेव तयोः समाहार इत्यर्थः ॥ नैरन्तर्येणेति । तस्यादित उदात्तमित्युक्तेः ॥

(६२९ गुणसमाहारानुपपत्तिवार्तिकम् ॥ २ ॥)

॥ * ॥ गुणयोश्चेन्नाच्प्रकरणात् ॥ * ॥

(भाष्यम्) **गुणयोः समाहार इति चेत् । तन्न ॥ किं कारणम् ? ॥ अच्प्रकरणात् । अजिति वर्तते ॥**

(प्रदीपः) अच्प्रकरणादिति । प्रकरणं प्रस्तावो न तु स्वरितत्वादनुवृत्तिः । तस्याः पूर्वं प्रत्याख्यानात् । तदयमर्थः । पूर्वसूत्रयोः सामर्थ्याक्षिप्तोऽजेव संज्ञी उदात्तानुदात्तशब्दयोरिति ताविहानुवृत्तावचं प्रत्याययतो न तु गुणम् ॥

(उद्द्योतः) पूर्वं प्रत्याख्यानेनाच्प्रकरणादिति विरुद्धमत आह—प्रस्ताव इति । सामर्थ्यादवगतिरित्यर्थः । तदुपपादयति—तदयमिति । अजिति वर्तत इति भाष्येऽच्शब्देन तद्विशेषबोधकावुदात्तानुदात्तशब्दौ लक्ष्येते इत्यर्थः ॥

(६३० समाधानवार्तिकम् ॥ ३ ॥)

॥ * ॥ सिद्धं त्वच्समुदायस्याभावात्तद्गुणसम्प्रत्ययः ॥ * ॥

(भाष्यम्) **सिद्धमेतत् ॥ कथम्? ॥ अच्समुदायो नास्तीति कृत्वा तद्गुणस्याचः समाहारगुणस्य सम्प्रत्ययो भविष्यति ॥**

(प्रदीपः) सिद्धं त्विति । गुणिनोरचोः समाहारासम्भवात्सामर्थ्याद् गुणयोः समाहाराश्रयणमित्यर्थः ॥

(उद्द्योतः) भाष्ये तद्गुणस्येत्यस्य व्याख्या समाहारगुणस्येति । उदात्तानुदात्तसमाहाररूपगुणवत इत्यर्थः ॥

(आक्षेपभाष्यम्)

कथं पुनः समाहार इत्यनेनाच्छक्यः प्रतिनिर्देष्टुम् ? ॥

(प्रदीपः) कथं पुनरिति । स्वरित इत्यनया संज्ञया योग्यत्वादच्संज्ञित्वेनाक्षिप्तः । न चाच्समाहारो भवति ॥

(उद्द्योतः) अचः संज्ञित्वेनानुपादानादयं प्रश्नोऽयुक्तोऽत आह—स्वरित इति ॥ न चाच्समाहार इति । भावसाधनत्वात्समाहारशब्दस्येति भावः ॥

(समाधानभाष्यम्)

मतुब्लोपोऽत्र द्रष्टव्यः । तद्यथा—पुष्पका एषां ते पुष्पकाः कालका एषां ते कालका इति । एवं समाहारवान् समाहारः ॥ अथ वा अकारो मत्वर्थीयः । तद्यथा तुन्दो घाट इति ॥

(प्रदीपः) मतुब्लोप इति । गुणगुणिनोरभेदोपचाराद्गम्यमानार्थस्य मतुपोऽप्रयोग इत्यर्थः ॥ अकार इति । अर्शआदेराकृतिगणत्वात् ॥

(उद्द्योतः) अर्श आदेरिति । अधिकरणे घञिति तु नोक्तं, ल्युटा बाधाद् बाहुलकस्यागतिकगतित्वात् ॥

(आक्षेपभाष्यम्)

यद्येवं त्रैस्वर्यं न प्रकल्पते ॥ तत्र को दोषः ? ॥ 'त्रैस्वर्येणाधीमहे' इत्येतन्नोपपद्यते ।

(प्रदीपः) त्रैस्वर्यमिति । उदात्तानुदात्तगुणव्यतिरेकेण स्वरितत्वस्याभावात्त्रैस्वर्यव्यवहारो न स्यात् । अस्ति चायं व्यवहारः ॥

(उद्द्योतः) उदात्तेत्यादि । स्वरशब्दस्य गुणपरत्वाभिप्रायं चोद्यमित्यर्थः ॥ त्रैस्वर्यमिति । भावे ष्यञिति भावः ॥

(समाधानभाष्यम्)

नैतद्गुणापेक्षम् ॥ किं तर्हि ? ॥ अजपेक्षमेतत्—'त्रैस्वर्येणाधीमहे' त्रिप्रकारैरज्भिरधीमहे, कैश्चिदुदात्तगुणैः कैश्चिदनुदात्तगुणैः कैश्चिदुभयगुणैः । तद्यथा—शुक्लगुणः शुक्लः, कृष्णगुणः कृष्णः, य इदानीमुभयगुणः स तृतीयामाख्यां लभते—कल्माष इति वा सारङ्ग इति वा । एवमिहापि उदात्त उदात्तगुणः, अनुदात्तोऽनुदात्तगुणः य इदानीमुभयगुणः स तृतीयामाख्यां लभते स्वरित इति ॥ समाहारः स्वरितः ॥ ३१ ॥

(प्रदीपः) अजपेक्षमिति । स्वरशब्देनाच उच्यन्ते । त्रय एव स्वरास्त्रैस्वर्यमिति स्वार्थे ष्यञ् ॥ ३१ ॥

(उद्द्योतः) ननु स्वरशब्दस्य गुणे प्रसिद्धेः कथं त्रैस्वर्यमित्यस्याजपेक्षत्वमत आह—**स्वरशब्देनेति** । एवमपि प्यन्नुपपत्तिरत आह—**त्रय एवेति** । चातुर्वर्ण्यादित्वादिति भावः ॥ ३१ ॥

(८८ स्वरित उदात्तावस्थितिसूत्रम् ॥ १।२।१ आ. २० सू.)

१०६ तस्यादित उदात्तमर्धह्रस्वम् ॥ १ । २ । ३२ ॥

(आक्षेपभाष्यम्)

अर्धह्रस्वमित्युच्यते । तत्र दीर्घप्लुतयोर्न प्राप्नोति। कन्या । शक्तिके३ शक्तिके ॥

(प्रदीपः) **तस्यादित उदात्त** ॥ ३२ ॥ अक्परिमाणस्य ह्रस्वसंज्ञा कृता **नाव्यपवृक्तस्येति** न्यायाद्दीर्घप्लुतावयवो ह्रस्वग्रहणेन न गृह्यत इत्यालोच्याह—**अर्धह्रस्वमिति** ॥ **कन्येति** । कन्याराजन्यमनुष्याणामन्त इति स्वरितः ॥ **शक्तिके ३ शक्तिके इति । स्वरितमाम्रेडितेसूयेति** स्वरितः प्लुतः ॥

(उद्द्योतः) **तस्यादितः ॥ ३२ ॥ अक्परिमाणस्येति** । अनवयवस्येत्यर्थः । **अव्यपवृक्तो**, ऽवयवः ॥ **इति न्यायादिति** । इति हेतोर्न्यायादवाच्यवृत्त्यैवेत्यर्थः ॥ **शक्तिक** इत्यत्र वाक्यादेरामन्त्रितस्येति द्वित्वम् ॥

(समाधानभाष्यम्)

नैष दोषः । मात्रचोऽत्र लोपो द्रष्टव्यः । अर्धह्रस्वमात्रमर्धह्रस्वमिति ॥

(प्रदीपः) **मात्रच इति** । अर्द्धह्रस्वशब्दः प्रमाणवाची रूढिशब्दः । व्युत्पत्त्यर्थं तु ह्रस्वस्योपादानम् । अर्द्धमात्रात्वेनाभिधीयते । ततः प्रमेये मात्रचं विधाय तस्य **प्रमाणे ल** इति लोपः क्रियते । तत्र यथा ह्रस्वे बुद्ध्यार्द्धमात्रा विभज्यते एवं दीर्घप्लुतयोरपीति ॥

(उद्द्योतः) नन्वर्द्धह्रस्वशब्दस्यावयववचनत्वेन प्रमाणवचनत्वाभावात्कथं मात्रजत आह—**अर्धह्रस्वेति** ॥ रूढ्याऽर्धमात्रारूपप्रमाणविशेषेनेनोच्यते, न ह्रस्वस्य अर्द्धमित्यर्थ इति भावः ॥ **व्युत्पत्त्यर्थमिति** । अनुलोमादिवदिति भावः । एवमपि दीर्घादावर्द्धमात्राकालावयवविभागाभावाद्दोष एवेत्यत आह—**तत्र यथेति** । उभयोरपि समा गतिरिति भावः ॥

(आक्षेपभाष्यम्)

किमर्थं पुनरिदमुच्यते ? ।

(प्रदीपः) **किमर्थमिति** । नैवंभूतमिहान्वाख्यानं दृश्यते सन्ध्यक्षरादिविषयस्यापि विभागस्यान्वाख्यानप्रसङ्गादिति प्रश्नः ॥

(उद्द्योतः) ननु गुणयोः प्रमाणोद्देशविशेषप्रतिपादनरूपान्वाख्यानार्थत्वात् प्रश्नोनुपपन्नोत आह—**नैवम्भूतमिति** ॥ **सन्ध्यक्षरादीति** । अवर्णभागः पूर्वं इकारादिभाग उत्तर इत्येवंरूपस्येत्यर्थः ॥

(समाधानभाष्यम्)

आमिश्रीभूतमिवेदं भवति । तद्यथा—क्षीरोदके सम्पृक्ते आमिश्रीभूतत्वान्न ज्ञायते-कियत् क्षीरम्, कियदुदकम्, कस्मिन्नवकाशे क्षीरम्, कस्मिन्वोदकमिति । एवमिहाप्यामिश्रीभूतत्वान्न ज्ञायते-कियदुदात्तम्, कियदनुदात्तम्, कस्मिन्नवकाशे उदात्तम्, कस्मिन्ननुदात्तमिति । तदाचार्यः सुहृद्भूत्वान्वाचष्टे इयदुदात्तमियदनुदात्तमस्मिन्नवकाश उदात्तम्, अस्मिन्नवकाशेनुदात्तमिति ॥

(प्रदीपः) **आमिश्रीभूतमिवेति** । तत्त्वतोस्त्येव विभाग इति इवशब्द उपात्तः ॥ **क्षीरोदके इति** । नियतव्यक्तिविवक्षायां जातिपरत्वाभावादेकवद्भावो न कृतः ॥

(उद्द्योतः) तत्त्वत इति । अन्यथान्वाख्यानासङ्गतिरिति भावः ॥

(आक्षेपभाष्यम्)

यद्ययमेवं सुहृत्किमन्यान्यप्येवंजातीयकानि नोपदिशति ॥ कानि पुनस्तानि ? । स्थानकरणानुप्रदानानि ॥

(उद्द्योतः) भाष्ये—**स्थानेत्यादि** । स्थानानि, कण्ठादीन्यर्थः । करणमाभ्यन्तरप्रयत्नः, अनुप्रदानं बाह्यप्रयत्नः ॥

(समाधानभाष्यम्)

व्याकरणं नामेयमुत्तरा विद्या । सोसौ छन्दःशास्त्रेष्वभिविनीत उपलब्ध्याधिगन्तुमुत्सहते ॥

(प्रदीपः) **उत्तरा विद्येति** । पुरा कल्पे पूर्वा, अद्यत्वे तूत्तरेति पस्पशायामाख्यातम् ॥

(उद्द्योतः) उत्तरयति—**व्याकरणं नामेति** ॥ **छन्दःशास्त्रेषु** प्रातिशाख्यशिक्षादिषु ॥ **अभिविनीतः** । शिक्षितः ॥ **उपलब्ध्या** । व्युत्पत्त्या ॥

(सूत्रप्रत्याख्यानभाष्यम्)

यद्येवं नार्थोऽनेन । इदमप्युपलब्ध्याधिगमिष्यति ।

(उद्द्योतः) एवं तर्हि इदमपि व्यर्थमाह—**यद्येवमिति** ॥

(संज्ञापक्षभाष्यम्)

संज्ञाकरणं तर्हीदम् । तस्य स्वरितस्यादितोर्धह्रस्वमुदात्तसंज्ञं भवतीति ॥ किं कृतं भवति ? । त्रिरुदात्तप्रदेशेषु स्वरितग्रहणं न कर्तव्यं भवति ।

"उदात्तस्वरितपरस्य सन्नतरः"। "उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य"। "नोदात्तस्वरितोदयमगार्ग्यकाश्यपगालवानाम्" इति ॥

(प्रदीपः) संज्ञाकरणमिति। प्रदेशेषु नैकदेशप्रत्यायनात्समुदाय आक्षेप्स्यते इति भावः ॥

(उद्योतः) ननु प्रदेशेषु स्वरितग्रहणाकरणे उदात्तग्रहणेनावयवस्य बोधनेपि तत्स्थाने यणोभावाद् उदात्तस्वरितयोर्यण इत्यत्रानुपपत्तिरेवेत्यत आह—आक्षेप्स्यत इति। तत्र सूत्रे एतदुपस्थितिसामर्थ्यादिति भावः ॥

(संज्ञापक्षनिराकरणभाष्यम्)

एतदपि नास्ति प्रयोजनम्। संज्ञाकरणं हि नाम यतो न लघीयः। कुत एतत्। लघ्वर्थं हि संज्ञाकरणम्। लघीयश्च त्रिरुदात्तप्रदेशेषु स्वरितग्रहणं न पुनः संज्ञाकरणम्। त्रिरुदात्तप्रदेशेषु स्वरितग्रहणे नवाक्षराणि। संज्ञाकरणे पुनरेकादश ॥

(संज्ञापक्षसाधकभाष्यम्)

एवं तर्ह्युभयमनेन क्रियते। अन्वाख्यानं च संज्ञा च ॥ कथं पुनरेकेन यत्नेन उभयं लभ्यम्? ॥ लभ्यमित्याह ॥ कथम्? ॥ अन्वर्थग्रहणात्। अन्वर्थग्रहणं विज्ञास्यते। तस्य स्वरितस्यादितोऽर्धह्रस्वमुदात्तसंज्ञं भवति। ऊर्ध्वमात्तमिति चात उदात्तम् ॥

(प्रदीपः) उभयमिति। सत्यप्यक्षरगौरवे महतोऽर्थस्य व्याप्तिर्भवति सुखेन विभागस्यापि परिज्ञानात् ॥

(उद्योतः) सत्यपीति। प्रयोजनविशेषलाभाद् गौरवं न दोषायेति भावः ॥ भाष्ये—ऊर्ध्वमात्तमिति। ताल्वादिषूर्ध्वदेशे उच्चारणेन गृहीतमित्यर्थः ॥

(संज्ञापक्षबाधकभाष्यम्)

यदि तर्हि संज्ञाकरणम् उदात्तादेर्यदुच्यते तत्स्वरितादेरपि प्राप्नोति ॥

(प्रदीपः) उदात्तादेरिति। उदात्तादेः प्रतिपादकं यच्छास्त्रमाद्युदात्तश्चेति तत् स्वरितादेरपि प्रतिपादकं प्राप्नोति ततश्च प्रत्ययः कदाचित् स्वरितादिरपि स्यादित्यर्थः ॥

(उद्योतः) उदात्तादेरुच्यमानं कार्यमिह शास्त्रे न किंचिदत आह—उदात्तादेरिति। इदमुपलक्षणमन्तोदात्तस्यापि ॥

(समाधानभाष्यम्)

अन्वाख्यानमेव तर्हीदं मन्दबुद्धेः ॥

(प्रदीपः) अन्वाख्यानमेवेति। न केवलमिदं सूत्रम्। यावदुच्चैरुदात्त इत्यादिसंज्ञाकरणमपि मन्दबुद्धिप्रतिपादनार्थम्। सिद्धो हि वेदाध्यायिनां शिक्षायामेवोदात्तादिव्यवहारः ॥

(उद्योतः) एवंभूतमन्वाख्यानं न दृश्यत इति यदुक्तं तत्परिहरति—न केवलमिति। उच्चैरुदात्त इत्यादिकमपि तादृशमिति भावः ॥ भाष्ये इदमित्यस्योच्चैरुदात्त इत्यादिकमित्यर्थो बोध्यः ॥

(६३१ सूत्रपाठव्यत्ययवार्तिकम् ॥ १ ॥)

॥ * ॥ स्वरितस्यार्धह्रस्वोदात्तादोदात्तस्वरितपरस्य सन्नतरादूर्ध्वमुदात्तादनुदात्तस्य स्वरितात् कार्यं स्वरितादिति सिद्ध्यर्थम् ॥ * ॥

(भाष्यम्) स्वरितस्यार्धह्रस्वोदात्ताद् आ "उदात्तस्वरितपरस्य सन्नतरः" इत्येतस्मात् सूत्रादिदं सूत्रकाण्डमूर्ध्वम् "उदात्तादनुदात्तस्य स्वरितः" इत्यतः कर्तव्यम् ॥ किं प्रयोजनम्? । स्वरितादिति सिद्ध्यर्थम्। स्वरितादिति सिद्धिर्यथा स्यात्—"स्वरितात्संहितायामनुदात्तानाम्" इति। इमं मे गङ्गे यमुने सरस्वति शुतुद्रि ॥ क्व तर्हि स्यात्?। यः सिद्धः स्वरितः—कार्यं देवदत्तयज्ञदत्तौ।

(प्रदीपः) स्वरितस्येति। आ अर्धह्रस्वोदात्तादित्याकारप्रश्लेषः। इयं नवसूत्री "उदात्तादनुदात्तस्य स्वरित" इत्येतस्मात्परा कर्तव्या। तेन स्वरितात् संहितायामनुदात्तानामित्येकश्रुतौ विधीयमानायामुदात्तादिति स्वरितस्य सिद्धत्वं भवति। तेन मेशब्दात् स्वरितात्परेषां गङ्गेप्रभृतीनामामन्त्रितत्वादनुदात्तानामेकश्रुतिर्भवति ॥ क्व तर्हीति। आश्रयासिद्धत्वं स्वरितस्य भविष्यतीत्यभिप्रायः ॥ कार्यमिति। अत्र तित्स्वरितमिति स्वरितत्वम्, तच्च सिद्धमित्यत्रैव स्यात् ॥

(उद्योतः) आकारप्रश्लेष इति। तदभावेऽर्धह्रस्वोदात्तादिति पञ्चम्यनन्विता स्यादिति भावः ॥ आरब्धयमारम्भाभिविध्योरिति तत्फलितमाह—इयं नवेति ॥ तेन मेशब्दादिति। किद्स्वरेणेदमोन्तोदात्तत्वादिममित्येकादेशस्वरेणान्तोदात्तं ततो मेशब्दस्यानुदात्तं सर्वमपादादावित्यनुदात्तत्वे इममित्युदात्तात्परत्वेनोदात्तादनुदात्तस्येति स्वरितत्वं ततो गङ्गेप्रभृतीनामामन्त्रितस्येत्याष्टमिकेन निहतानामेकश्रुतिः ॥ अत्र तिदिति। तदेकादेशोप्यान्तरतम्यात् स्वरितः। करोतेर्ण्यति कार्यम्। तदुत्तरं देवदत्तयज्ञदत्तावित्यामन्त्रितस्य चेति निहतम् ॥

(६३२ प्रयोजनवार्तिकम् ॥ २ ॥)

॥ * ॥ स्वरितोदात्तार्थं च ॥ * ॥

(भाष्यम्) स्वरितोदात्तार्थं च तत्रैव कर्तव्यम्। "न सुब्रह्मण्यायां स्वरितस्य तूदात्तः" इन्द्र आगच्छ ॥ क्व तर्हि स्यात्? ॥ यःसिद्धः स्वरितः—सुब्रह्मण्योमिन्द्रागच्छ ॥

(प्रदीपः) स्वरितोदात्तार्थमिति। स्वरितस्य च

उदात्तो विधीयते स आष्टमिकस्यासिद्धत्वान्न प्राप्नोति ॥ **सुब्रह्मण्योमिति ।** सुब्रह्मणि साधुरिति यत्प्रत्ययस्तित्त्वात्स्वरितः । ततष्टाबेकादेशः स्वरितानुदात्तयोरान्तरतम्यात्स्वरितः । तत **ओमाङोश्चे**त्युदात्तस्वरितयोरेकादेशः स्वरित एव तस्य सिद्धत्वादुदात्तत्वम् ॥ सुब्रह्मण्यायामिति च स्वरूपमेव गृह्येत न तु निगदो लक्ष्येत ॥

(उद्द्योतः) भाष्ये **इन्द्र आगच्छेति ।** आङुदात्तः गच्छेति निहतम् । तत **उदात्तादनुदात्तस्ये**ति गकाराकारः स्वरितः । तस्यानेनोदात्तः । इन्द्रेत्यामन्त्रितमाद्युदात्तं द्वितीयो वर्ण **उदात्ता**दिति स्वरितः, तस्याप्यनेनोदात्तः ॥ **स्वरित एवेति ।** एकादेश उदात्तेनेत्यत्रानुदात्तस्येत्यनुवृत्तेः स नेति भावः । न **चेको गुणे**ति सूत्रे **एङि पररूप**मित्यत्र रूपग्रहणस्य परस्य यादृशं रूपं तादृश एव यथा स्यादिति फलमुक्तमिति, अत्र ओम उदात्तत्वादुदात्त एकादेशो युक्त इति वाच्यम् । **तृज्वत्क्रोष्टु**रिति सूत्रभाष्यप्रामाण्येन स्वरस्य रूपत्वाभावात् ॥ ननु सुब्रह्मण्यायामिति निगदाभिधानादयमेव विषयो न युक्त इत्यत आह—**सुब्रह्मण्यायामिति । स्वरितस्य तूदात्त** इति वाक्ये सुब्रह्मण्याशब्दस्वरूपमेव गृह्यतेत्यर्थः ॥

(६३३ प्रयोजनवार्तिकम् ॥ ३ ॥)

॥ * ॥ स्वरितोदात्तार्थम् ॥ * ॥

(भाष्यम्) **स्वरितोदात्तार्थं तत्रैव कर्तव्यम् । इन्द्रागच्छ हरिव आगच्छ ॥**

(प्रदीपः) **स्वरितोदात्तार्थेति ।** आगच्छेत्यत्र गशब्दाकारस्य स्वरितस्योदात्तत्वे कृते **उदात्तादनुदात्तस्य स्वरित** इति छशब्दाकारस्य स्वरितत्वं प्राप्नोति ॥

(उद्द्योतः) **उदात्तत्वे कृते इति ।** न **सुब्रह्मण्यायामि**त्यनेन । उत्कर्षे त्वस्यासिद्धत्वाच्छशब्दाकारोनुदात्त एवेत्यर्थः ॥

(६३४ प्रयोजनवार्तिकम् ॥ ४ ॥)

॥ * ॥ स्वरितपरसन्नतरार्थं च ॥ * ॥

(भाष्यम्) **स्वरितपरसन्नतरार्थं च तत्रैव कर्तव्यम् । "उदात्तस्वरितपरस्य सन्नतरः" माणवकजटिलकाध्यापकन्यङ् ॥ क तर्हि स्यात् ? ॥ यः सिद्धः स्वरितः 'माणवक जटिलकाभिरूपक क' ।**

(प्रदीपः) **न्यङ्ङिति । न्यधी चेति** पूर्वपदप्रकृतिस्वरस्तत **उदात्तस्वरितयोर्यण** इत्यकारः स्वरितस्तस्यासिद्धत्वात् पूर्वस्य सन्नतरो न स्यात् ॥

(उद्द्योतः) **न्यधी चेति ।** अञ्चतौ वप्रत्ययान्त उत्तरपदे नि अधि इत्येतत्पूर्वपदं प्रकृतिस्वरमिति सूत्रार्थः । **न्यङ्स्वरौ स्वरिता**विति फिट्सूत्रमेतदर्थस्यैवानुवादकमिति भावः ॥ **क्वेति ।** अव्ययान्तत्वात्स्वरितम् ॥

(तटस्थाक्षेपभाष्यम्)

तत्तर्हि वक्तव्यम् ॥

(समाधानभाष्यम्)

न वक्तव्यम् ।

(६३५ पाठव्यत्ययप्रत्याख्यानवार्तिकम् ॥ ५ ॥)

॥ * ॥ देवब्रह्मणोरनुदात्तवचनं ज्ञापकं स्वरितादिति सिद्धत्वस्य ॥ * ॥

(भाष्यम्) **देवब्रह्मणोरनुदात्तवचनं ज्ञापकं सिद्ध इह स्वरित इति ॥**

(प्रदीपः) **देवब्रह्मणोरिति ।** लिङ्गात्पाठक्रमबाधेन क्रमान्तरमाश्रीयतेऽन्यथा स्वरितस्यासिद्धत्वादनुदात्तस्यानुदात्तविधानमनर्थकं स्यात् ॥

(उद्द्योतः) **देवब्रह्मणोरिति ।** अनयोः सुब्रह्मण्यानिगदान्तर्गतयोः स्वरितस्योदात्तत्वे प्राप्तेऽनेनानुदात्तत्वं क्रियते ॥ **देवा ब्रह्माण इति** चामन्त्रिताद्युदात्तः, ततः शेषनिघाते **उदात्तादनुदात्तस्ये**ति स्वरितः ॥

(ज्ञापनबाधकभाष्यम्)

यद्येतज् ज्ञाप्यते, स्वरितोदात्तात्परस्यानुदात्तस्य स्वरितत्वं प्राप्नोति ॥

(प्रदीपः) **यद्येतदिति ।** स्वरितस्यैव सिद्धत्वमनेन लिङ्गेन ज्ञाप्यत इत्यर्थः ॥

(उद्द्योतः) **स्वरितस्यैवेति ।** स्वरितस्यैव सिद्धत्वमात्रज्ञापने त्वस्य प्रकरणस्यासिद्धत्वे मानाभावात् ॥

(ज्ञापनान्तरभाष्यम्)

न ब्रूमो देवब्रह्मणोरनुदात्तवचनं ज्ञापकं सिद्ध इह स्वरित इति ॥ किं तर्हि ? । परमेतत्सूत्रकाण्डमिति ॥ तस्यादित उदात्तमर्धह्रस्वम् ॥ ३२ ॥

(प्रदीपः) **न ब्रूम इति ।** सन्निवेशान्तरज्ञापनार्थं लिङ्गं व्याख्यायत इत्यर्थः ॥ ३२ ॥

(उद्द्योतः) **न सुब्रह्मण्येति** विहितस्वरितोदात्तगकारात्परत्वेनेन्द्र आगच्छेत्यादौ छकाराकारस्याष्टमिकः स्वरितः स्यादित्युत्कर्ष एव ज्ञाप्यत इति बोध्यम् ॥ असिद्धकाण्डे पठनमेव **संनिवेशान्तरम् ।** न च **देवब्रह्मणोरि**त्यत्राश्रयात् सिद्धत्वमिति वाच्यम् । इष्टानुरोधेनैतत्प्रकरणोत्कर्षद्वारैव तत्सिद्धत्वज्ञापनादिति दिक् ॥ ३२ ॥

(इति स्वरिते उदात्तानुदात्तभागस्थितिनिर्णयः)

(अथ स्वरविधिप्रकरणम् ॥)

(८९ एकश्रुतिविधानसूत्रम् ॥ १।२।१ आ० २१ सू०)

१०७ एकश्रुति दूरात्संबुद्धौ ॥१।२।३३॥

(आक्षेपभाष्यम्)

किमिदं पारिभाषिक्याः संबुद्धेर्ग्रहणम् "एकवचनं संबुद्धिः" इति । आहोस्विदन्वर्थग्रहणं संबोधनं

संबुद्धिरिति? ॥ किं चातः? । यदि पारिभाषिक्याः संबुद्धेर्ग्रहणं देवा ब्रह्माणः, अत्र न प्राप्नोति । अथान्वर्थग्रहणं, न दोषो भवति ॥

(प्रदीपः) एक॥३३॥किमिति । कृत्रिमाकृत्रिमयोः कृत्रिमे संप्रत्यय इत्युभयगतिरिह शास्त्रे भवतीति च न्यायद्वयसम्भवात्प्रश्नः ॥

(उद्योतः) एकश्रुति ॥ ३३ ॥ एकवचनं सम्बुद्धिरित्युक्तेर्विचारानुपपत्तिरत आह—कृत्रिमेति ॥

(समाधानभाष्यम्)

यथा न दोषस्तथास्तु ॥

(प्रदीपः) यथा न दोष इति । नहि दूरादिति विशेषणमेकवचनस्योपपद्यते । सम्बोधनस्य तु क्रियारूपत्वादपादानतया दूरादिति विशेषणसम्भवः।व्याप्तिश्चान्वर्थग्रहणे भवति ॥

(उद्योतः) अकृत्रिमग्रहणं सामर्थ्याद्भवतीत्यतः सामर्थ्यं दर्शयति—नहीति ॥ ननु कृत्रिमग्रहणेऽपि महासंज्ञावलाद् दूरात्संबोधनार्थकैकवचनान्तस्येत्यर्थलाभोऽत आह—व्याप्तिश्चेति ॥

(एकश्रुतिस्वरूपवर्णनभाष्यम्)

(आक्षेपभाष्यम्)

किं पुनरियमेकश्रुतिरुदात्ता, आहोस्विदनुदात्ता? ॥

(प्रदीपः) किं पुनरिति । उदात्तानुदात्तानुरागवशात्प्रश्नः ॥

(उद्योतः) अस्याः स्वरान्तरत्वप्रसिद्धेः प्रश्नानुपपत्तिरत आह—उदात्तेति ॥

(समाधानभाष्यम्)

नोदात्ता ॥ कथं ज्ञायते? ॥ यदयम् "उच्चैस्तरां वा वषट्कारः" इत्याह ॥ कथं कृत्वा ज्ञापकम्? ॥ अतन्त्रं तरनिर्देशः । यावदुच्चैस्तावदुच्चैस्तराम् ॥

(प्रदीपः) यावदुच्चैरिति । यदि चोदात्तैकश्रुतिरभविष्यत्तदा यज्ञकर्मणीत्येकश्रुतेः सिद्धत्वादुच्चैस्तरां वा वषट्कार इति सूत्रं नाकरिष्यदित्यर्थः ॥

(उद्योतः) उच्चैस्तरामिति । तेनोदात्तमात्रस्य विधानात्पक्षे एकश्रुतेश्च विधानादिति भावः ॥

(आक्षेपभाष्यम्)

यदि तर्हि नोदात्ता अनुदात्ता ॥

(समाधानभाष्यम्)

अनुदात्ता च न ॥ कथं ज्ञायते? ॥ यदयम् "उदात्तस्वरितपरस्य सन्नतरः" इत्याह ॥ कथं कृत्वा ज्ञापकम्? ॥ अतन्त्रं तरनिर्देशः ॥ यावत्सन्नस्तावत्सन्नतरः ॥ सैषा ज्ञापकाभ्यामुदात्तानुदात्तयोर्मध्यमेकश्रुतिरन्तरालं ह्रियते ॥

(प्रदीपः) यावत्सन्न इति । तत्रैकश्रुत्यनुदात्तस्यैव सिद्धत्वात्सन्नतरविधानमनर्थकं स्यात् ॥ अन्तरालं ह्रियत इति । हरतेर्द्विकर्मकत्वात्प्रधाने कर्मणि लकारः ॥ क्षीरोदकवदुदात्तानुदात्तयोर्भेदतिरोधानमेकश्रुतिरित्यर्थः । स्वरिते तु विभागेन तयोरुपलब्धिः ॥

(उद्योतः) भाष्ये सैषा ज्ञापकाभ्यामिति । ज्ञापकाभ्यां कर्तृभ्याम्, एकश्रुतिरुदात्तानुदात्तयोर्मध्यस्थानं प्राप्यत इत्यर्थः । मध्यमित्यस्यान्तरालमिति व्याख्या ॥ हरतेरिति । व्यापारद्वयार्थत्वात् प्रधानकर्मण्याख्येये लादीनाद्विकर्मणाम्, इति वचनाच्च ॥ स्वरिताद्विशेषं दर्शयितुमाह—क्षीरेति ॥

(व्याख्यान्तरभाष्यम्)

अपर आह—

(आक्षेपभाष्यम्)

किमियमेकश्रुतिरुदात्ता, आहोस्विदनुदात्ता? ॥

(समाधानभाष्यम्)

उदात्ता ॥ कथं ज्ञायते? ॥ यदयम् "उच्चैस्तरां वा वषट्कार" इत्याह ॥ कथं कृत्वा ज्ञापकम्? ॥ तन्त्रं तरनिर्देशः । उच्चैर्दृष्ट्वा उच्चैस्तरामित्येतद्भवति ।

(प्रदीपः) उच्चैर्दृष्ट्वेति । सोमस्याग्ने वीही वौषट् इत्यत्र मन्त्रे यज्ञकर्मणीत्यनेनैकश्रुतिर्विहिता तदपेक्षया वौषट्शब्दस्योदात्ततरत्वं विधीयते । सति चैकश्रुतेरुदात्तानुरागे तदपेक्षः प्रकर्षो युज्यते। यथा मलिने वस्त्रे शौक्ल्यानुबन्धसद्भावात्तदपेक्षो वस्त्रान्तरेषु शुक्लतरव्यपदेश इत्यर्थः ॥

(उद्योतः) सति चेति । वौषट्व्यतिरिक्तमन्त्रभागस्योदात्तत्वे सत्येव तदपेक्षप्रकर्षप्रत्ययोपपत्तिरिति भावः ॥ एकश्रुतिगतोदात्तापेक्षया प्रकर्षानुपपत्तिमाशङ्क्य दृष्टान्तेन साधयति—यथेति । अत्रापि पक्षे भेदतिरोधानमेव स्वरिताद्विशेषस्तेनैव चोभयरूपतेति बोध्यम् । एवं च सन्नतर एकश्रुतिविषये एवेति बोध्यम् ॥ सप्तस्वरमध्ये उदात्ततरानुदात्ततरावेकश्रुतिगतोदात्ताद्यपेक्षयैवातिशयविशिष्टौ न तु स्वतन्त्रोदात्तापेक्षया ॥

(आक्षेपभाष्यम्)

यदि तर्ह्युदात्ता नानुदात्ता ॥

(समाधानभाष्यम्)

अनुदात्ता च ॥ कथं ज्ञायते? ॥ यदयम् "उदात्तस्वरितपरस्य सन्नतरः" इत्याह ॥ कथं कृत्वा ज्ञापकम्? ॥ तन्त्रं तरनिर्देशः । सन्नं दृष्ट्वा सन्नतर इत्येतद्भवति ॥ त एते तन्त्रे तरनिर्देशे सप्त स्वरा भवन्ति—उदात्तः, उदात्ततरः, अनुदात्तः, अनुदात्ततरः, स्वरितः, स्वरिते य उदात्तः सोऽन्येन विशिष्टः, एकश्रुतिः सप्तमः ॥ एकश्रुतिदूरात्संबुद्धौ ॥ ३३ ॥

(प्रदीपः) सन्नं दृष्ट्वेति । एकश्रुतिगतमित्यर्थः ॥ सोऽन्येनेति । अनुदात्तेनोपरक्तः यथा शुक्लः पटो वर्णान्तरयुक्तेन द्रव्येणेत्यर्थः ॥ कस्य चित्तु स्वरितस्योदात्तभागो नानुदात्ते-

नानुरज्यते इति पृथक्स्वरितो निर्दिष्टः । स्वरितस्य भेदा जात्यस्वरादयोऽष्टाविति भाष्यकारेणाप्रकृतत्वादिह नोक्ताः । इयं चैकश्रुतिराहुतासंबोधनवाक्यस्य भवति । प्लुतस्तूदात्त एव विधानसामर्थ्यात् ॥ ३३ ॥

(उद्योतः) अनुदात्तेनेति । उदात्तस्वरितपरत्वे इत्यर्थः ॥ कस्य चिदिति । तदपरस्येत्यर्थः ॥ प्लुतस्त्विति । तस्य वैकल्पिकत्वाद्यदा स जायते तदेत्यर्थः ॥ ३३ ॥

(९० एकश्रुतिनिषेधसूत्रम् ॥ १।२ । १ आ० २२ सू० ॥)

१११ न सुब्रह्मण्यायां स्वरितस्य तूदात्तः ॥ १ । २ । ३७ ॥

(६३६ सूत्रशेषवार्तिकम् ॥ १ ॥)

॥ * ॥ सुब्रह्मण्यायामोकार उदात्तः ॥ * ॥

(भाष्यम्) सुब्रह्मण्यायामोकार उदात्तो भवति॥ 'सुब्रह्मण्योम्' ।

(प्रदीपः) न सु॥३७॥ओकार इति । नेदमपूर्वविधानं सूत्रव्यापार एव तु प्रदर्श्यते । यथा चोदात्त ओकारस्तथा तस्यादित इत्यत्रोक्तम् । ओमभ्यादान इति तु प्लुतोदात्तत्वं न भवति । तस्यायज्ञकर्मविषयत्वादित्याहुः ॥ इन्द्र आगच्छेतीन्द्रशब्द आमन्त्रितत्वादाद्युदात्तः तस्य द्वितीयो वर्णो वर्ज्यमानस्वरेणानुदात्तः । स उदात्तादनुदात्तस्य स्वरित इति स्वरितस्तस्यानेनोदात्तत्वम् ॥

(उद्योतः) न सुब्रह्मण्या ॥ ३७ ॥ न चात्रोदात्तोन्यथा सिद्ध इत्याह—ओमिति । अभ्यादानपदेनायज्ञकर्मोच्यत इति भावः ॥ अत एव जपेऽपि तं प्लुतमेव जपन्ति ॥ अभ्यादानं प्रारम्भ इति तु वृत्तिः । तद्रीत्या त्वत्र प्राप्तिरेव नेति बोध्यम् ॥ स्वरितस्य तूदात्त इत्यंशस्योदाहरणान्तरं प्रसङ्गादाह—इन्द्र आगच्छेति ॥ इन्द्रशब्द इति । हरिवच्छब्दस्याप्युपलक्षणम् । हरिव इति मतुवसोरिति रुः ॥

(६३७ सूत्रशेषवार्तिकम् ॥ २ ॥)

॥ * ॥ आकार आख्याते परादिश्च ॥ * ॥

(भाष्यम्) आकार आख्याते परादिश्चोदात्तो भवति ॥ 'इन्द्र आगच्छ' 'हरिव आगच्छ ॥

(प्रदीपः) आकार आख्यात इति । तिङन्ते गच्छशब्दे परत आकार उपसर्गत्वादुदात्तः ॥ परादिश्चेति । आकारात्परस्य गच्छेत्यस्यादिरुदात्तः । तिङ्ङतिङ इति निघाते पूर्ववत्स्वरिते च कृतेऽनेनोदात्तविधानात् ॥

(६३८ सूत्रशेषवार्तिकम् ॥ ३ ॥)

॥ * ॥ वाक्यादौ च द्वे ॥ * ॥

(भाष्यम्) वाक्यादौ च द्वे उदात्ते भवतः इन्द्र आगच्छ हरिव आगच्छ ।

(प्रदीपः) वाक्यादौ चेति । अनन्तरोक्तप्रक्रिययेति भावः ।

(उद्योतः) अनन्तरेति 'इन्द्र आगच्छेतीन्द्रशब्द' इत्याद्यनुपदोक्तयेति भावः । एतन्निमित्तः शेषनिघातस्तु न । अस्यासिद्धत्वात् ॥ भाष्ये द्वे इति । वर्णरूपे इत्यर्थः ॥

(६३९ सूत्रशेषवार्तिकम् ॥ ४ ॥)

॥ * ॥ मघवन्वर्जम् ॥ * ॥

(भाष्यम्) आगच्छ मघवन् ।

(प्रदीपः) मघवन्वर्जमिति । मघवान्नत्यस्यामन्त्रितस्येति निघातविधानात् ॥

(उद्योतः) श्वः सुत्यामागच्छ मघवन्निति वाक्यम् तत्र श्वः शब्दो निपातत्वादुदात्तः, सुत्याशब्दः संज्ञायां समजेतिक्यबन्तो-

---

*जात्यस्वरेति । तथा च शुक्लयजुःप्रातिशाख्यसूत्राणि साभियुक्तकारिकाणि मस्तूयन्ते—

(प्रा. सू.) एकपदे नीचपूर्वः सयवो जात्यः ॥ १ अ. १११ सू.

'एकपदे नीचपूर्वः सयवो जात्य इष्यते ।
अपूर्वोपि परस्तद्वद्धान्यं कन्या स्वरित्यपि ॥'

'कन्या इव' 'धान्यमसि' । अनुदात्तापूर्वो यथा—स्वर्देवेषु

(प्रा. सू.) एदोद्भ्यामकारो लुप्तमभिनिहितः ॥ १ अ. ११४ सू.

'ए ओ आभ्यामुदात्ताभ्यामकारो रिफितश्च यः ।
अकारो लुप्यते यत्र तं चाभिनिहितं विदुः ॥''

इति ॥ यथा तेऽप्सरसाम् वेदोऽसि ॥

(प्रा. सू.) युवर्णौ यवौ क्षैप्रः ॥ १ अ. ११५ सू. ॥

इ उ वर्णौ यदोदात्तावापद्येते यवौ क्वचित् ।
अनुदात्ते पदे नित्यं विद्यात्क्षैप्रस्य लक्षणम् ॥

यथा—नु=इन्द्र=न्विन्द्र ॥ वाजी=अर्वन्=वज्यर्वन् ।

(प्रा. सू.) इवर्णो उभयतो ह्रस्वः प्रश्लिष्टः ॥ १ अ. ११६ सू. ॥

इकारो दृश्यते यत्र इकारेण च संयुतः ।
उदात्तश्चानुदात्तेन प्रश्लिष्टो भवति स्वरः ॥''

यथा अभीन्धताम् ॥

(प्रा. सू.) स्वरो व्यञ्जनयुतस्तैरो व्यञ्जनः ॥ १ अ. ११७ सू.

उदात्तपूर्वं यत् किंचिद्व्यञ्जनेन युतं पदम् ।
एष सर्वगुरुः स्वारस्तैरो व्यञ्जन इष्यते ॥ यथा इडेरन्त ।

(प्रा. सू.) उदवग्रहस्तैरोविरामः ॥ १ अ. ११८ सू.

अवग्रहात्परो यस्तु स्वरितः स्यादनन्तरम् ।
तैरोविरामं तं विद्यादुदात्तो यद्यवग्रहः ॥''

यथा गोपताविति गोऽपतौ ॥ यज्ञपतिमिति यज्ञऽपतिम् ॥

(प्रा. सू.) विवृत्तिलक्षणः पादवृत्तः ॥ १ अ. ११९ सू.

स्वरे च स्वरिते चैव विवृत्तिर्यत्र दृश्यते ।
पादवृत्तो भवेत्स्वारो विनऽइन्द्रेति दर्शनम् ॥

(प्रा. सू.) उदाद्यन्तोऽन्यवग्रहस्तथाभाव्यः ॥ १ अ. १२० सू.

अवग्रहो यदा नीच उच्चयोर्मध्यतः क्वचित् ।
तथाभाव्यो भवेत्कम्पस्तनूनप्त्रे निदर्शनम् ॥

ऽन्तोदात्तः, तत्रोदात्त इत्यनुवर्तते॥ निघातविधानादिति । पूर्वच्छकारस्याप्यनुदात्तत्वेन स्वरितप्राप्त्या स्वरितस्य तूदात्त इत्यस्याप्राप्तेरिति भावः । तत एकश्रुति दूराद्विलेकश्रुतिस्तत्रेति तत्त्वम् ॥

(६४० शेषवार्तिकम् ॥ ५ ॥)

॥ * ॥ सुत्यापराणामन्तः ॥ * ॥

(भाष्यम्) सुत्यापराणामन्त उदात्तो भवति । 'द्व्यहे सुत्याम्' 'त्र्यहे सुत्याम्' ॥

(प्रदीपः) सुत्यापराणामिति । सुत्याशब्दः परो येभ्यस्तेषामित्यर्थः ॥ द्व्यह इति । टजन्तत्वादन्तोदात्तत्वम् ॥

(उद्द्योतः) सुत्याशब्द इति । सर्वनामकार्याभावाद्नुमोहित्वनिश्चयः । श्वःशब्दस्थाने द्व्यहे इत्यादयः ॥

(६४१ शेषवार्तिकम् ॥ ६ ॥)

॥ * ॥ असावित्यन्तः ॥ * ॥

(भाष्यम्) असावित्यन्त उदात्तो भवति । 'गार्ग्यो यजते' 'वात्स्यो यजते' ॥

(प्रदीपः) असावित्यन्त इति । इदं वाचनिकम् ॥ असाविति प्रथमान्तोपलक्षणम् ॥ गार्ग्य इति । ञित्स्वादाद्युदात्तत्वे प्राप्ते अन्तोदात्तत्वविधिः ॥

(उद्द्योतः) इदमिति । अग्रिमाण्यप्येवम् ॥

(६४२ शेषवार्तिकम् ॥ ७ ॥)

॥ * ॥ अमुष्येत्यन्तः ॥ * ॥

(भाष्यम्) अमुष्येत्यन्त उदात्तो भवति । 'दाक्षेः पिता यजते' ॥

(प्रदीपः) अमुष्येति । षष्ठ्यन्तोपलक्षणमेतत् ॥ दाक्षेरिति । पूर्ववदाद्युदात्तत्वं प्राप्तम् ॥ ३७ ॥

(३४३ शेषवार्तिकम् ॥ ८ ॥)

॥ * ॥ स्यान्तस्योपोत्तमं च ॥ * ॥

(भाष्यम्) स्यान्तस्योपोत्तममुदात्तं भवति । अन्त्यश्च । 'गार्ग्यस्य पिता यजते' 'वात्स्यस्य पिता यजते' ॥

(उद्द्योतः) स्यान्तस्येति । चेन उपोत्तमान्त्योदात्तयोः समुच्चयः ॥ ३७ ॥

(६४४ शेषवार्तिकम् ॥ ९ ॥)

॥ * ॥ वा नामधेयस्य ॥ * ॥

(भाष्यम्) वा नामधेयस्य स्यान्तस्योपोत्तममुदात्तं भवति । 'देवदत्तस्य पिता यजते' । 'देवदत्तस्य पिता यजते' ॥ न सुब्रह्मण्यायाम् ॥ ३७ ॥

(९१ एकश्रुतिबाधकानुदात्तविधिसूत्रम् ॥ १ । २ । १ आ० २३ सू०)

११२ देवब्रह्मणोरनुदात्तः ॥ १ ।२।३८॥

(६४५ सूत्रस्य पाक्षिकत्वसूचकवार्तिकम् ॥ १ ॥)

॥ * ॥ देवब्रह्मणोरनुदात्तत्वमेके ॥ * ॥

(भाष्यम्) देवब्रह्मणोरनुदात्तत्वमेक इच्छन्ति । देवा ब्रह्माणः, देवा ब्रह्माणः ॥ देवब्रह्मणोरनु०॥३८

(प्रदीपः) देव ॥ ३८ ॥ अनुदात्तत्वमेक इति । ये 'देवा ब्रह्माणः' इति पदयोर्वैयधिकरण्यमाहुस्तदा हि पूर्वस्यामन्त्रितस्याविद्यमानत्वाद् द्वयोरपि पदयोरामन्त्रिताद्युदात्तत्वे शेषनिघाते च स्वरितत्वे च कृतेऽनेनानुदात्तः क्रियते । यदा तु देवाः ब्रह्माण इत्यनयोः सामानाधिकरण्यं तदा विभाषितं विशेषवचने बहुवचनमिति पक्षे विद्यमानत्वादामन्त्रितस्येति निघातस्य सिद्धत्वान्नानेनार्थ इत्यन्येषां मतमिति मतभेदप्रदर्शनार्थमेक इत्युक्तम् ॥ ३८ ॥

(उद्द्योतः) देवब्रह्मणो ॥ ३८ ॥ भाष्योक्तमेक इति व्याचष्टे—ये इति । ये आहुस्ते एके इत्यर्थः । एके इत्युक्तिर्न विभाषाग्रहणानुवृत्तिकृता किन्तु ब्रह्मांशे सूत्रारम्भानैयत्यबोधिकेति भावः ॥ तदा हि—वैयधिकरण्ये हि ॥ अविद्यमानत्वादिति । आमन्त्रितं पूर्वमित्यनेन ॥ एके इत्यनेन ध्वनितं मतान्तरं दर्शयितुमाह—यदा त्विति ॥ नानेनार्थ इति । ब्रह्माण इत्यत्रानुदात्तार्थेनेत्यर्थः । देवार्थं तु कार्यमेव ॥ भाष्ये त्वेवं योजना—देवब्रह्मणोर्मध्ये ब्रह्मन्शब्दस्यानेनानुदात्तत्वमेके वैयधिकरण्यवादिन इच्छन्ति । सामानाधिकरण्यपक्षे दे इत्येक एवोदात्तः । वैयधिकरण्यवादिनां तु दे इति ब्र इति च द्वयमुदात्तम् । इदमेव ध्वनयितुं द्विःपाठ उदाहरणस्येति बोध्यम् ॥ केचित्तु वेदार्थस्याव्यवस्थितत्वे मानाभावादिदं चिन्त्यम् । किंच पक्षे विद्यमानत्वेपि पक्षेऽविद्यमानत्वस्यापि सत्त्वेन मेत्यस्योदात्तस्याग्रिमस्यानुदात्तस्य च श्रवणाय सूत्रमावश्यकमेव । भाष्यं तु विभाषानुवृत्तिफलकमेव । तथा च पक्षे आमन्त्रितस्वरेणाद्युदात्तस्य देवशब्दस्य ब्रह्मशब्दस्य चान्तोऽनेनानुदात्तः स्वरितस्य तूदात्त इत्यस्यायमपवादः । सुसु तत्रानुदात्त एव । पक्षान्तरे तु पूर्वसूत्रेणान्तेप्युदात्ते एकश्रुतिर्दूरादित्येकश्रुतिः । अत एवैकश्रुतीति सूत्रे सम्बुद्धिपदार्थनिरूपणावसरे देवा ब्रह्माण इत्यत्रैकश्रुतिरुक्ता भाष्ये ॥ इदं च सूत्रं वृत्तावेवं व्याख्यातं सुब्रह्मण्यायां देवा ब्रह्माण इति पठ्यते तत्र पूर्वेण स्वरितस्योदात्ते प्राप्तेऽनेन तस्यानुदात्तो विधीयत इति । एकश्रुतिसूत्रोदाहृतं देवा ब्रह्माण इति सुब्रह्मण्यानिगदस्यातिरिक्तमेवेत्यत्र न मानमित्याहुः ॥ ३८ ॥

(९२ एकश्रुतिविधिसूत्रम् ॥ १ । २ । २ आ० २४ सू०)

स्वरितात्संहितायामनुदात्तानाम्
॥ १ । २ । ३९ ॥

(द्व्येकयोरप्येकश्रुतिसाधनाधिकरणम्)

(६४५ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ स्वरितात्संहितायामनुदात्तानामिति चेद् द्व्येकयोरैकश्रुत्यवचनम् ॥*॥

(भाष्यम्) स्वरितात्संहितायामनुदात्तानामिति चेद् द्व्येकयोरैकश्रुत्यं वक्तव्यम् । आग्निवेश्यः पचतीति ॥ किं पुनः कारणं न सिध्यति ? ॥ बहुवचननिर्देशात् ॥ बहुवचनेनायं निर्देशः क्रियते । तेन बहूनामेवैकश्रुत्यं स्याद् द्व्येकयोर्न स्यात् ॥

(प्रदीपः) स्वरि ॥ ३९ ॥ द्व्येकयोरिति । पशुना यजेतेतिवत्संख्याया विवक्षितत्वात् ॥ आग्निवेश्य इति । यञन्तत्वादादिरुदात्तः । शेषनिघातः, ततो द्वितीयो वर्ण उदात्तादिति स्वरितः, तस्मात्परौ द्वावनुदात्तौ ॥ पचतीति । धातुरुदात्तः शप्तिपावनुदात्तौ । ततः शबकारः स्वरितः, ततः पर एकोनुदात्तः ॥ द्व्येकयोरित्यत्र द्विशब्देन द्वित्वमुच्यते, एकशब्देन चैकत्वम् । तेन द्वित्वे एकत्वे च सतीत्यर्थः ॥

(उद्द्योतः) स्वरितात् ॥ ३९ ॥ सङ्ख्याया इति । अनुदात्तानामिति पदोपात्तव्यक्तिगताया इति शेषः । उपात्तस्याविवक्षाकारणाभावादिति भावः ॥ संख्येयप्रधानत्वे द्व्येकेषामिति स्यादत आह—द्वित्वमिति ॥ नन्वेवं संख्याया ऐकश्रुत्यविधानायोगात्षष्ठ्यनुपपन्नेत्यत आह—तेनेति । अनुदात्तद्वित्वादौ सति तदधिकरणभूतानामैकश्रुत्यं वक्तव्यमिति भाष्यार्थः ॥

(आक्षेपबाधकभाष्यम्)

नैष दोषः । नात्र बहुवचनेन निर्देशस्तन्त्रम् ॥

(प्रदीपः) नात्रेति । तन्त्रशब्दोऽत्र प्रधानवाची यथा ग्रहं संमार्ष्टीति संख्या न विवक्ष्यते तथेहापीत्यर्थः ॥

(उद्द्योतः) तन्त्रशब्द इति । विवक्षितत्वलक्षणं प्राधान्यम् ॥ भाष्ये—नात्रेति । अनुवादस्थल इत्यर्थः । व्याप्तिन्यायश्चाविवक्षाहेतुरिति बोध्यम् ॥

(आक्षेपसाधकभाष्यम्)

कथं पुनस्तेनैव च नाम निर्देशः क्रियते, तच्चातन्त्रं स्यात् ? । तत्कारी च भवांस्तद्द्वेषी च ॥

(प्रदीपः) तत्कारीति । असत्यां बहुत्वसंख्यायां बहुवचनमेव न स्यादिति तद्विवक्षणीयम् । नात्र निर्देशस्तन्त्रमिति वचनात्तदेवाविवक्षितमिति विरोध इत्यर्थः ॥

(आक्षेपबाधकभाष्यम्)

नान्तरीयकत्वादत्र बहुवचनेन निर्देशः क्रियते—अवश्यं कयाचिद्विभक्त्या केनचिद्वचनेन निर्देशः कर्तव्य इति । तद्यथा । कश्चिदन्नार्थी शालिकलापं सपलालं सतुषमाहरति नान्तरीयकत्वात् । स यावदादेयं तावदादाय तुषपलालान्युत्सृजति । तथा कश्चिन्मांसार्थी मत्स्यान् सकण्टकान् सशकलानाहरति नान्तरीयकत्वात् । स यावदादेयं तावदादाय शकलकण्टकान्युत्सृजति । एवमिहापि नान्तरीयकत्वाद् बहुवचननिर्देशः क्रियते । अविशेषेणैकश्रुत्यं भवति ॥

(प्रदीपः) नान्तरीयकत्वादिति । शब्दसंस्कारार्थमेवात्र बहुत्वं विवक्ष्यते न तु कार्यसिद्ध्यर्थमित्यर्थः ॥ तुषपलालानीति । तुषसहितानि पलालानीति तत्पुरुषः । द्वन्द्वे तु जातिवाचित्वादेकवद्भावप्रसङ्गः । एवं शकलकण्टकानीति ॥

(उद्द्योतः) विनार्थकान्तराशब्दाद् भवार्थे छो गहादित्वात्, स्वार्थे कः, नञ्समासो नलोपाभावश्च पृषोदरादित्वान्नान्तरीयक शब्दे ॥ ननु बहुत्वसंख्याविवक्षापूर्वकत्वाद्बहुवचनस्य नान्तरीयकत्वमयुक्तमत आह—शब्देति । शब्दकृतः संस्कारः, तदुच्चारणकृतमदृष्टं तदर्थमित्यर्थः । सौत्रं बहुवचनमिति तात्पर्यम् ॥ न तु कार्येति । शब्दानां कार्यमर्थोपस्थितिः सा प्रकृते न विवक्षितेत्यर्थः॥ सशल्कानिति पाठः ॥

(६४६ आक्षेपवार्तिकम् ॥ २ ॥)

॥ * ॥ अविशेषेणैकश्रुत्यमिति चेद् व्यवहितानामप्रसिद्धिः ॥ * ॥

(भाष्यम्) अविशेषेणैकश्रुत्यमिति चेद् व्यवहितानामैकश्रुत्यं न प्राप्नोति—'इमं मे गङ्गे यमुने सरस्वति शुतुद्रि' ॥

(प्रदीपः) व्यवहितानामिति । स्वरितादिति पञ्चमीनिर्देशादनन्तरस्यैव कार्येण भाव्यमिति—इमं मे गङ्गे इत्यत्र मेशब्दात्स्वरितात्परस्यैकस्यैवानन्तरस्य स्याद्, न द्वितीयादीनां व्यवधानादित्यर्थः ॥

(उद्द्योतः) व्यवधानादित्यर्थ इति । बहुत्वविवक्षायां तु सामर्थ्यात्परिभाषाबाध इति भावः ॥

(६४७ समाधानन्यासान्तरवार्तिकम् ॥ २ ॥)

॥ * ॥ अनेकमपीति तु वचनात्सिद्धम् ॥ * ॥

(भाष्यम्) अनेकमप्येकमपि स्वरितात्परं संहितायामेकश्रुति भवतीति वक्तव्यम् ॥

(आक्षेपभाष्यम्)

सिध्यति । सूत्रं तर्हि भिद्यते ॥

(समाधानभाष्यम्)

यथान्यासमेवास्तु ॥

(आक्षेपस्मारणभाष्यम्)

ननु चोक्तम्—*स्वरितात्संहितायामनुदात्ताना-मिति चेद् द्व्येकयोरैकश्रुत्यवचनम्* *अविशेषेणेति चेद् व्यवहितानामप्रसिद्धिः* इति ॥

(दूषणनिराकरणभाष्यम्)

नैष दोषः ॥ कथम्? ॥ एकशेषनिर्देशोयम् । अनुदात्तस्य चानुदात्तयोश्चानुदात्तानां चानुदात्ता-नामिति ॥

(प्रदीपः) **एकशेषनिर्देशोयमिति ।** योगारम्भपक्षे वर्गत्रयोपादानेनैकशेषः क्रियते । अनुदात्तयोरनुदात्तानामिति च कृते एकशेषे पुनरेकशेषः कर्तव्यः ॥ आकृतिपक्षाश्रयेण तु प्रत्याख्याते सूत्रे जात्याख्यायामिति बहुवचनं कृतम्, तत-श्चैकद्विबहुषु स्वरितात्परस्या जातेरानन्तर्येणोपलम्भात्सर्वेषामैक-श्रुत्यस्य सिद्धत्वाद्दोषाभावः ॥

(उद्योतः) **योगारम्भे इति ।** एकशेषसूत्रारम्भे इत्यर्थः ॥ एकशेषेपि त्रिप्रभृतिष्वेव स्याद् अत आह—**वर्गत्रयेति ।** तात्पर्य-वशाद्भिन्नसंख्याकलितेत्यर्थः ॥ **जातेः ।** अनुदात्तत्वजातेः । व्यक्ति-द्वारा परत्वं कार्यसंबन्धश्चेति बोध्यम् ॥ तत्राव्यवहितव्यक्तिद्वारैव सर्वगतजातेः परत्वं बोध्यम् ॥ इदं चिन्त्यमेकैकव्यक्तिव्यङ्ग्यत्वाज्जा-तेस्तद्व्यक्तिद्वारकं परत्वं तद्व्यक्तिव्यङ्ग्यायाः । किं चार्धधातुके इति सूत्रस्थभाष्याद्व्यक्तिद्वारकं परत्वादि जातेरयुक्तमिति निरूपितं **हल-न्ताच्चेति** सूत्रे ॥ तस्मादेकशेषप्रत्याख्यानेपि भिन्नसंख्याकलितप्रा-तिपदिकार्थानां तत्रं भिन्नसंख्याकलितार्थकप्रातिपदिकानां वा ॥ **जात्याख्यायामित्यस्यापि** भाष्ये प्रत्याख्यातत्वेनेदमेव युक्तमिति परे ॥

(आक्षेपभाष्यम्)

एवमपि षट्प्रभृतीनामेव प्राप्नोति । षट्प्रभृतिषु ह्येकशेषः परिसमाप्यते ॥

(प्रदीपः) **एवमपीति ।** सहविवक्षायामेकशेषविधाना-त्समुदितानां कार्यप्रसङ्गः ॥

(उद्योतः) ननु वर्गत्रयोपादानेनैकशेषकरणा**देवमपी**त्याद्य-नुपपन्नमत आह—**सहविवक्षायामिति ।** एकया क्रियया गुणेन वाऽनेकस्य युगपत्सम्बन्धप्रतिपादनेच्छा सहविवक्षेत्यर्थः ॥

(समाधानभाष्यम्)

प्रत्येकं वाक्यपरिसमाप्तिर्दृष्टेति द्व्येकयोरपि भ-विष्यति ॥ स्वरितात्संहितायामनुदात्तानाम् ॥३९॥

(प्रदीपः) प्रभृतिग्रहणेन चैकशेषवाक्येऽनुदात्तानामित्यने-नैव चतुरादयोप्यनुदात्ता गृह्यन्ते इति दर्शयति—**प्रत्येक-मिति ।** निर्देश एव सहविवक्षा । कार्यप्रवृत्तिस्तु प्रत्येकं यथा देवदत्तयज्ञदत्तविष्णुमित्रा भोज्यन्तामित्युक्ते देवदत्तादयः पृथ-गेव भुञ्जते ॥ ३९ ॥

(उद्योतः) षण्णामित्येव वक्तव्ये प्रभृतिग्रहणमधिकमत आह—**प्रभृतीति ॥ एकशेषवाक्ये ॥** एकशेषविग्रहवाक्ये ॥ **निर्देश एवेति ।** बोध एवेत्यर्थः ॥ **यथेति ।** तत्रैव 'मातापित्रोः श्राद्धं कुर्यात्' इत्यत्रेव चात्रापि निर्देश एव सहविवक्षेत्यदोषः ॥३९॥

(इति स्वरविधिप्रकरणम्)

(९३ अपृक्तसंज्ञासूत्रम् ॥ १ । २ ।१ आ. २५ सू.)

११५ अपृक्त एकाल्प्रत्ययः ॥१।२।४१॥

(हल्ग्रहणे लाघवाभावोपपादनाधिकरणम्)

(६४९हल्ग्रहणवादिन आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ अपृक्तसंज्ञायां हल्ग्रहणं स्वादि-लोपे हलोऽग्रहणार्थम् ॥ * ॥

(भाष्यम्) अपृक्तसंज्ञायां हल्ग्रहणं कर्तव्यम् । एकहल्प्रत्ययोऽपृक्तसंज्ञो भवतीति वक्तव्यम् ॥ किं प्रयोजनम्? ॥ स्वादिलोपे हलोऽग्रहणार्थम् । एवं हि स्वादिलोपे हलो ग्रहणं न कर्तव्यं भवति "ह-ल्ङ्याब्भ्यो दीर्घात्सुतिस्यपृक्तं हल्" इति । अपृक्त-स्येत्येव सिद्धम् ॥

(प्रदीपः) अपृक्त ॥ ४१ ॥ **स्वादिलोप इति ।** विभेदेति णलोऽपृक्तग्रहणेनैव निवृत्तिः सिध्यतीत्यर्थः ॥

(६५० अल्ग्रहणवादिनः प्रयोजनवार्तिकम् ॥ २ ॥)

॥ * ॥ अणिञोर्लुगर्थमल्ग्रहणम् ॥ * ॥

(भाष्यम्) अणिञोर्लुगर्थमल्ग्रहणं **कर्तव्यम् ॥** किं प्रयोजनम्? ॥ अणिञोर्लुकि ग्रहणं न कर्तव्यं भवति "ण्यक्षत्रियार्षञितो यूनि लुगणिञोः" इति । अपृक्तस्येत्येव सिद्धम् ॥

(प्रदीपः) **अणिञोरिति ।** पदद्वयोच्चारणमेव गौरव-मिति भावः ॥

(उद्योतः) अपृक्त ए ॥ ४१ ॥ अपृक्तग्रहणेऽक्षराधिक्या-दाह—**पदद्वयेति ।** अपृक्तमित्यखण्डमिति भावः ॥

(६५१ अल्ग्रहणे दूषणवार्तिकम् ॥ ३ ॥)

॥ * ॥ अणिञोर्लुगर्थमिति चेण्णेऽति-प्रसङ्गः ॥ * ॥

(भाष्यम्) अणिञोर्लुगर्थमिति **चेण्णेऽतिप्रसङ्गो भवति । इहापि प्राप्नोति—फाण्टाहृतेरपत्यं माण-वकः फाण्टाहृत इति ॥**

(अल्ग्रहणे दूषणबाधकभाष्यम्)

णवचनसामर्थ्यान्न भविष्यति ॥

(प्रदीपः) णवचनेति । लुगपवादो णो विज्ञास्यते । अन्यथाऽण एव लुकि सिद्धे णविधानमनर्थकं स्यादित्यर्थः ॥

(उद्द्योतः) युवापत्यसंप्रत्ययार्थत्वाद् णस्य कथं सामर्थ्यमत आह—लुगपेति ॥ अण एव । तस्यापत्यमिति सामान्यविहितस्य ॥

(६५२ अल्ग्रहणे दूषणसाधकवार्तिकम् ॥ ४ ॥)

॥ * ॥ वचनप्रामाण्यादिति चेत् फङ्निवृत्त्यर्थं वचनम् ॥ * ॥

(भाष्यम्) वचनप्रामाण्यादिति चेत् फङ्निवृत्त्यर्थमेतत्स्यात् । फगतो मा भूदिति ॥

(प्रदीपः) फङ्निवृत्त्यर्थमिति । यञिञोश्चेति प्राप्तस्य फको बाधनार्थं णवचनं स्यात् तस्य च लुक्स्यादेवेत्यर्थः ।

(उद्द्योतः) प्राप्तस्येति । अणपवादत्वेनेति शेषः ॥

(६५३ अल्ग्रहणे समाधानवार्तिकम् ॥ ५ ॥)

॥ * ॥ पैलादिषु वचनात्सिद्धम् ॥ * ॥

(भाष्यम्) यद्येतावत्प्रयोजनं स्यात् पैलादिष्वेवास्य पाठं कुर्वीत । तत्र पाठादन्येषामपि फको निवृत्तिर्भवति । एवं सिद्धे सति यदयं णं शास्ति तज्ज्ञापयत्याचार्यो नास्य लुग्भवतीति ॥

(अल्ग्रहणे लाघवाभावभाष्यम्)

तान्येतानि त्रीणि ग्रहणानि भवन्ति—अपृक्तसंज्ञायां हल्ग्रहणं कर्तव्यम् । स्वादिलोपे हलो ग्रहणं न कर्तव्यम् । अणिञोर्लुकि ग्रहणं कर्तव्यम् ॥ अल्ग्रहणेपि वै क्रियमाणे तान्येव त्रीणि ग्रहणानि भवन्ति—अपृक्तसंज्ञायामल्ग्रहणं कर्तव्यम् । स्वादिलोपे हलो ग्रहणं कर्तव्यम् । अणिञोर्लुकि ग्रहणं न कर्तव्यं भवति, अपृक्तग्रहणं कर्तव्यम् ॥ तत्र नास्ति लाघवकृतो विशेषः ॥

(उद्द्योतः) तदेवं णस्य लुगभावं प्रसाध्य हल्ग्रहण इवाल्ग्रहणेपि त्रीण्येव पदानीति पक्षद्वयसाम्यमित्याह—भाष्ये—तानीति । अनेन पदसाम्ये मात्रावैषम्यमकिंचित्करमिति सूचितम् ॥

(अल्ग्रहणे लाघवभाष्यम्)

अयमस्ति विशेषः । अल्ग्रहणे क्रियमाणे एकग्रहणं न करिष्यते ॥

(आक्षेपभाष्यम्)

कस्मान्न भवति दर्विर्जागृविः ? ॥

(प्रदीपः) कस्मान्न भवतीति । प्रत्ययस्य विशेषणमल्ग्रहणमिति तदन्तविधिसद्भाव इति मत्वा प्रश्नः ॥ इदं तु नाश्रितमनुनासिकपरत्वादिति ॥

(उद्द्योतः) ननु प्रत्ययेनाल्वि विशेष्यमाणे तदन्तविध्यभावात्कथमत्र प्राप्तिरत आह—प्रत्ययस्येति । व्याप्तिन्यायेनाल्व विशेषणमिति भावः ॥ ननु वेरपृक्तस्येत्यत्रानुनासिकः परो यतस्तस्य वेर्लोप इति वक्ष्यते कथं दर्वौ प्राप्तिः । अत एवास्येत इत्त्वं नेत्यत आह—इदं त्विति ॥

(समाधानभाष्यम्)

अलेव यः प्रत्ययः ॥

किं वक्तव्यमेतत् ? ।

नहि ॥

कथमनुच्यमानं गंस्यते ? ॥

अल्ग्रहणसामर्थ्यात् । यदि च योल् चान्यश्च तत्र स्यात्, अल्ग्रहणमनर्थकं स्यात् ॥

(प्रदीपः) अल्ग्रहणसामर्थ्यादिति । यद्यलन्तस्य स्यात्केवलस्य चाद्यन्तवद्भावात्तदाल्ग्रहणेन न किं चिद्व्यावर्तितं स्यात् ॥

(उद्द्योतः) भाष्ये अल्चेति । केवलालात्मक इत्यर्थः । अन्यश्चेति । समुदायात्मक इत्यर्थः ॥

(हल्ग्रहणेपि लाघवभाष्यम्)

हल्ग्रहणेपि वै क्रियमाणे एकग्रहणं न करिष्यते ॥

(आक्षेपभाष्यम्)

कस्मान्न भवति—दर्विः जागृविः ? ॥

(प्रदीपः) दर्विरिति ॥ ननु हलन्तत्वाभावादत्र प्राप्तिरेव नास्ति ॥ नैष दोषः । अयं साम्प्रतिको विशब्द इति क्विबादिषु भूतपूर्वगतिर्न लभ्यते तत्रापृक्तसंज्ञायां हल्ग्रहणेन हल्वान् गृह्येत । यथा गुरोश्च हल इत्यत्र गुरुमान् ॥

(उद्द्योतः) अयं साम्प्रतिक इति । वेरपृक्तस्येति सूत्रे उद्देश्यतया प्रधानस्य विग्रहणस्य मुख्यार्थत्वलाभाय हलित्यत्र सौत्रो मतुब्लोप इति भावः ॥

(समाधानभाष्यम्)

हलेव यः प्रत्ययः ॥ किं वक्तव्यमेतत् ? ॥ नहि ॥ कथमनुच्यमानं गंस्यते ? ॥ हल्ग्रहणसामर्थ्यात् । यदि च यो हल् चान्यश्च तत्र स्यात्, हल्ग्रहणमनर्थकं स्यात् ॥

(प्रदीपः) हलेवेति । हलः प्राधान्यात्प्रत्ययस्य च विशेषणत्वादित्यर्थः । क्विबादिषु भूतपूर्वगत्याश्रयणाद्गौणी चेत्कल्पना । अत्र हल्शब्देन तद्वतो ग्रहणे किं न गौणी ॥ हल्ग्रहणसामर्थ्यादिति । क्विबादयोऽपि हल्वन्तो दर्विरित्यादौ विप्रलयोपीति किमनेन व्यवच्छिन्नं स्यादित्यर्थः ॥

(उद्योतः) हलः प्राधान्यादिति । संज्ञावाक्यार्थप्रतिपत्युत्तरमेव प्रदेशार्थप्रतिपत्तेरसंजातविरोधन्यायेन तत्रोक्तकल्पनानुचितेति भावः ॥ किं च शास्त्रस्याल्पविषयतापत्तिरित्यपि बोध्यम् ॥ किं न गौणीति । क्लिष्टेत्यर्थः ॥ किमनेनेति । वेरपृक्तस्येत्यस्य लक्ष्यानुसारात् सर्वत्र प्रवृत्त्यङ्गीकारे इत्यर्थः ॥

(समाधानबाधकभाष्यम्)

अस्त्यन्यद्धल्ग्रहणस्य प्रयोजनम् ॥ किम्? । हलन्तस्य यथा स्यादजन्तस्य मा भूदिति ॥

(प्रदीपः) **हलन्तस्य यथा स्यादिति** । ततश्चासत्येकग्रहणे हन्यादित्यादौ तिलोपः स्यादिति कर्तव्यं हल्ग्रहणे क्रियमाणे एकग्रहणम् ॥

(उद्योतः) **तिलोपः स्यादिति** । आगमविशिष्टस्य तित्वाद् हलन्तत्वेनापृक्तत्वाच्च यादित्यस्य लोपः स्यादित्यर्थः । अत्र पक्षे हल्ङ्याब्भ्य इति सूत्रे हल्ग्रहणं नारभ्यत एवेति भावः ॥

(परिभाषासाधनभाष्यम्)

एवं तर्हि सिद्धे सति यद्धल्ग्रहणे क्रियमाणे एकग्रहणं करोति, तज्ज्ञापयत्याचार्यः—"अन्यत्र वर्णग्रहणे जातिग्रहणं भवति" इति ॥

किमेतस्य ज्ञापने प्रयोजनम्? ।

*** दम्भेर्हल्ग्रहणस्य जातिवाचकत्वात्सिद्धम् *' इत्युक्तं तदुपपन्नं भवति ॥ अपृक्त एकाल्प्रत्ययः ४१**

(प्रदीपः) अल्ग्रहणे तु क्रियमाणे न कर्तव्यं कृतं तु ज्ञापनार्थं तद्दर्शितं भाष्ये ॥ यद्यप्ययमर्थो **निपात एकाजनाङ्** इत्यत्रैकग्रहणेन ज्ञापितस्तथापि मन्दबुद्धीनामनुग्रहाय पुनरिह ज्ञापितः । अपृक्तप्रदेशेषु हल्ग्रहणेनैव सिद्धे संज्ञाविधानं विस्पष्टार्थम् ॥ **वृद्धिरादैज्** इत्यत्रास्य परिभाषात्वं व्यवस्थापितमिह कथं संज्ञात्वेन व्यवहारः । पारार्थ्यसामान्यात्परिभाषा संज्ञात्वेन व्यवह्रियते इत्यदोषः ॥ ४१ ॥

(उद्योतः) **अल्ग्रहणे त्विति** । तदुपादानसामर्थ्येन तदन्तविध्यभावादिति भावः ॥ **ज्ञापित इति** । एवं चात्र जातिग्रहणशङ्कावारणायैवैकग्रहणं चरितार्थमिति कथं ज्ञापकमिति भावः ॥ **पुनरिहेति** । युगपदेव विनिगमनाविरहात् प्रमाणद्वयप्रवृत्तिरिति भावः ॥ **वृद्धिरादैजिति** । अस्य तत्त्वं तत्रैवोक्तम् ॥ **व्यवस्थापितमिति** । मयेति शेषः ॥ ४१ ॥

(९४ कर्मधारयसंज्ञासूत्रम् ॥ १ । २ । १ आ. २६ सू०)

११६ तत्पुरुषः समानाधिकरणः कर्मधारयः ॥ १ । २ । ४२ ॥

(सामानाधिकरण्योपपादनाधिकरणम्)

(६५४ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ तत्पुरुषस्समानाधिकरणः कर्मधारय इति चेत्समासैकार्थत्वाद्प्रसिद्धिः ॥ * ॥

(भाष्यम्) **तत्पुरुषः समानाधिकरणः कर्मधारय इति चेत् समासैकार्थत्वात् संज्ञाया अप्रसिद्धिः । एकोयमर्थस्तत्पुरुषो नाम । अनेकार्थाश्रयं च सामानाधिकरण्यम् ॥**

(प्रदीपः) तत्पुरुषः ॥४२॥ **समासैकार्थत्वादिति** । भिन्नप्रवृत्तिनिमित्तप्रयुक्तस्यानेकस्य शब्दस्यैकस्मिन्नर्थे वृत्तिः **सामानाधिकरण्यमुच्यते** । नीलोत्पलादिश्च तत्पुरुष एक एवेति सामानाधिकरण्यमनुपपन्नम् । वर्तिपदानां तु सामानाधिकरण्यमुपपद्यते, तत्पुरुषत्वं तु तेषां नास्ति ॥

(उद्योतः) तत्पुरुषः ॥ ४२ ॥ **समासैकार्थत्वादिति** वार्तिके समासस्यैकप्रवृत्तिनिमित्तत्वादित्यर्थः ॥ पर्यायव्यावृत्त्यर्थम्—**भिन्नेति** । भिन्नप्रवृत्तिनिमित्तप्रकारकभिन्नोपस्थितिजनकस्येत्यर्थः । वस्तुतः पर्यायाणामपि कोशे सामानाधिकरण्यस्येष्टताया **नामन्त्रिते समानाधिकरणे** इति सूत्रे भाष्ये ध्वनितत्वेनेदं चिन्त्यम् ॥ गौरश्व इत्यादौ तद्व्यावृत्तये—**एकस्मिन्नर्थ इति** ॥ भाष्ये—**एकोयमर्थस्तत्पुरुषो नामेति** । तत्पुरुषसंज्ञकनीलोत्पलादिशब्दार्थ एक एकोपस्थितिरित्यर्थः ॥ यद्येकविशेष्यकप्रतीतिजनकत्वं सामानाधिकरण्यं तदा तत्पुरुषमात्रस्य कर्मधारयत्वापत्तिः समानाधिकरणपदवैयर्थ्यं चेति तात्पर्यम् ॥ **तत्पुरुषत्वमिति** । समासादिसंज्ञा समुदायनिवेशिनीति भावः ॥

(६५५ न्यासान्तरसमाधानवार्तिकम् ॥ २ ॥)

॥ * ॥ सिद्धं तु पदसामानाधिकरण्यात् ॥ * ॥

(भाष्यम्) **सिद्धमेतत् ॥ कथम्? ॥ तत्पुरुषस्समानाधिकरणपदः कर्मधारयसंज्ञो भवतीति वक्तव्यम् ॥**

(आक्षेपभाष्यम्)

सिध्यति । सूत्रं तर्हि भिद्यते ॥

(सिद्धान्तिभाष्यम्)

यथान्यासमेवास्तु ॥

(आक्षेपसारणभाष्यम्)

ननु चोक्तम्—*तत्पुरुषः समानाधिकरणः कर्मधारय इति चेत् समासैकार्थत्वादप्रसिद्धिः*इति ॥

(सिद्धान्तिसमाधानभाष्यम्)

नैष दोषः । अयं तत्पुरुषोस्त्येव प्राथमकल्पिको यस्मिन्नैकपद्यमैकस्वर्यमेकविभक्तित्वं च । अस्ति

तादर्थ्यात्ताच्छब्द्यं तत्पुरुषार्थानि पदानि तत्पुरुष इति । तद्यस्तादर्थ्यात्ताच्छब्द्यं तस्येदं ग्रहणम् ॥ तत्पुरुषः समानाधिकरणः कर्मधारयः ॥ ४२ ॥

(प्रदीपः) **ऐकपद्यमिति** । पदशब्देनार्थ उच्यते । ऐकार्थ्यमित्यर्थः । अथ वा समासाद्विभक्त्युत्पत्तौ सत्यामैकपद्यमुच्यते ॥ **एकविभक्तित्वमिति** । एककारकत्वमित्यर्थः ॥ **तद्य इति** ॥ ननु मुख्यस्य तत्पुरुषस्य पदान्तरेण सामानाधिकरण्यं संभवत्येव राजपुरुषः शोभन इत्यादौ, तत्कथं गौणस्य ग्रहणम् ॥ नैष दोषः । तत्पुरुषस्य पदान्तरेण सामानाधिकरण्यं बहिरङ्गम्, अन्तरङ्गं तु वर्तिपदानामिति तदेवाश्रीयते । ततश्च सामर्थ्यात्तत्पुरुषशब्दो गौणार्थवृत्तिः परिगृह्यते । तेन समासावयवानामेव पदानां कर्मधारयसंज्ञा विधीयते, समुदाये च वाक्यपरिसमाप्त्या पदसमुदायस्यैकैव कर्मधारयसंज्ञा, न तु प्रत्येकम् ॥ तत्पुरुषसंज्ञाप्रकरणे इयं संज्ञा न कृता, एकसंज्ञाधिकारात् तत्पुरुषसंज्ञाया बाधो मा भूदिति ॥ ४२ ॥

(उद्योतः) ननु एकपदत्वैकविभक्तित्वयोः पौनरुक्त्यमित्यत आह—**पदशब्देनेति** । पदतदर्थयोरभेदोपचारादिति भावः ॥ **अथ वेति** । अन्तर्वर्तिविभक्त्यपेक्षस्तूत्तरपदादिव्यवहार इति भावः ॥ नन्वेकविभक्तीति पुनरुक्तमत आह—**एककारकत्वमिति** । विभज्यतेऽनया प्रातिपदिकार्थ इति व्युत्पत्तेः ॥ **तद्य** इत्यादि भाष्ये **ताच्छब्द्यमिति** स्वार्थे ष्यञ् । **तत्** ततो हेतोर्मुख्यार्थे सामानाधिकरण्यासंभवाद्धेतोर्यस्तादर्थ्यात्तच्छब्दस्तस्येदं ग्रहणमित्यक्षरार्थः । यद्वा यस्तादर्थ्यात्ताच्छब्द्यं तच्छब्दवाच्यतां लभत इति शेषः ॥ **अन्तरङ्गं त्विति** । अर्थनिबन्धनसामानाधिकरण्याश्रयोन्तरङ्गन्यायस्तु तत्पुरुषशब्दमात्राश्रयगौणमुख्यन्यायात्प्रबल इति भावः ॥ ननु तत्पुरुषार्थपदानां कर्मधारयसंज्ञालाभेपि समुदायस्य सा न स्याद्, इष्यते च तस्येत्यत आह—**समुदाये चेति** । समानाधिकरणपदमर्शआद्यजन्तं तु नाश्रितं, तादृशानामपि गौणत्वात् ॥ **बाधो मा भूदिति** । तत्पुरुष इत्यनुवृत्तावपि पाक्षिको वाधो मा भूदित्यर्थः । **समानाधिकरणः कर्मधारयश्चे**ति तु सुवचं, द्विगुश्चेति वत् ॥ ४२ ॥

(९५ उपसर्जनसंज्ञासूत्रम् । १ । २ । १ आ. २७ सू.)

११७ प्रथमानिर्दिष्टं समास उपसर्जनम् ॥ १ । २ । ४३ ॥

(समासपदार्थनिरूपणाधिकरणम्)

(६५६ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ प्रथमानिर्दिष्टं समास उपसर्जनमिति चेदनिर्देशात् प्रथमायाः समासे संज्ञाप्रसिद्धिः ॥ * ॥

(भाष्यम्) प्रथमानिर्दिष्टं समास उपसर्जनमिति चेदनिर्देशात् प्रथमायाः समासे उपसर्जनसंज्ञाया अप्रसिद्धिः । नहि कष्टादीनां समासे प्रथमां पश्यामः ॥

(प्रदीपः) **प्रथमा ॥ ४३ ॥ अनिर्देशात्प्रथमाया इति** । समासे किं प्रथमानिर्दिष्टं भवितुमर्हति ? यस्मात्समासे प्रथमा विधीयते । न च तथाभूतस्य सम्भवः । समासे कृते तत एव प्रथमोत्पद्यते न तु तदवयवात् । अन्तर्वर्तिन्या च विभक्त्या प्रथमानिर्दिष्टत्वे आश्रीयमाणे कष्टश्रित इत्यत्र श्रितशब्दस्यैवोपसर्जनसंज्ञा स्यान्न कष्टशब्दस्य, निर्दिष्टग्रहणं चानर्थकं स्यात् । समासे प्रथमान्तमुपसर्जनमिति वक्तव्यं स्यात् ॥

(उद्योतः) **प्रथमानि० ॥ ४३ ॥ समासे किमिति** । समासे इति सप्तमीनिर्देशात्समासे विद्यमानं प्रथमान्तमिति सूत्रार्थं मत्वा वार्तिकारम्भ इत्याशयः ॥ **तत एवेति** । समासादेवेत्यर्थः । तथा च समासः प्रथमानिर्दिष्टः स्याद् न तु समासे किंचिदिति सप्तम्यनुपपत्तिः स्यादिति भावः ॥ **अन्तर्वर्तिन्येति** । समासे विद्यमानाद् यतः प्रथमोच्चार्यत इत्यर्थ इति भावः ॥ **न कष्टशब्दस्येति** । तच्चानिष्टमिति भावः ॥ **प्रथमान्तमिति** । संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिप्रतिषेधादन्तपदोच्चारणम् ॥

(६५७ न्यासान्तरसमाधानवार्तिकम् ॥ २ ॥)

॥ * ॥ सिद्धं तु समासविधाने वचनात् ॥ * ॥

(भाष्यम्) सिद्धमेतत् ॥ कथम् ? । समासविधाने प्रथमानिर्दिष्टमुपसर्जनसंज्ञं भवतीति वक्तव्यम् ॥

(आक्षेपभाष्यम्)

तर्हि वक्तव्यम् ॥

(६५८ समाधानवार्तिकम् ॥ ३ ॥)

॥ * ॥ न वा तादर्थ्यात्ताच्छब्द्यम् ॥ * ॥

(भाष्यम्) न वा वक्तव्यम् ॥ किं कारणम् ? । तादर्थ्यात्ताच्छब्द्यं भविष्यति । समासार्थं शास्त्रं समास इति ॥

(प्रदीपः) **न वेति** । मुख्यार्थासम्भवाद्गौणोर्थो गृह्यत इत्यर्थः ॥

(उद्योतः) **मुख्यार्थासंभवादिति** । निर्दिष्टग्रहणोपबृंहितसमासग्रहणस्य मुख्यार्थासंभवादित्यर्थः ॥

(अनिष्टापत्तिवारणाधिकरणम्)

(६५९ आक्षेपवार्तिकम् ॥ ४ ॥)

॥ * ॥ यस्य विधौ प्रथमानिर्देशस्ततोन्यत्रोपसर्जनसंज्ञाप्रसङ्गः ॥ * ॥

(भाष्यम्) यस्य विधौ प्रथमानिर्देशः क्रियते

ततोऽन्यत्रापि तस्योपसर्जनसंज्ञा प्राप्नोति । राज्ञः कुमारीं राजकुमारीं श्रितः । श्रितादिसमासे द्वितीयान्तं प्रथमानिर्दिष्टं तस्य षष्ठीसमासेऽप्युपसर्जनसंज्ञा प्राप्नोति ॥

(प्रदीपः) **यस्य विधाविति** । निर्देशापेक्षया समासस्याधारत्वात्प्रथमानिर्दिष्टस्य सर्वत्रोपसर्जनसंज्ञा प्राप्नोतीति भावः ॥ **राजकुमारीमिति** । सत्युपसर्जनत्वे ह्रस्वः स्यात् पूर्वनिपाताव्यवस्था च ॥

(उद्द्योतः) ननु प्रत्यासत्त्या यत्समासशास्त्रे यत् प्रथमानिर्दिष्टं तन्निरूपितकार्ये एव तदुपसर्जनं स्यादत आह—**निर्देशापेक्षयेति** । ईदृशप्रत्यासत्तिर्दुर्ज्ञेयेति भावः ॥ **सत्युपेति** । परिनिष्ठितविभक्त्या समास इति पक्षे इदम् । इदमेव ध्वनयितुं भाष्ये श्रितपदोपादानम् ॥

(६६० समाधानवार्तिकम् ॥ ५ ॥)

॥ * ॥ सिद्धं तु यस्य विधौ तं प्रतीति वचनात् ॥ * ॥

(भाष्यम्) **सिद्धमेतत् ॥ कथम् ? । यस्य विधौ यत्प्रथमानिर्दिष्टं तं प्रति तदुपसर्जनसंज्ञं भवतीति वक्तव्यम् ॥**

(प्रदीपः) **सिद्धं त्विति । यस्य** श्रितादेः समास**विधौ तं** श्रितादिकं प्रतीत्यर्थः ॥

(आक्षेपभाष्यम्)

तर्तर्हि वक्तव्यम् ॥

(समाधानभाष्यम्)

न वक्तव्यम् । उपसर्जनमिति हि महती संज्ञा क्रियते । संज्ञा च नाम यतो न लघीयः ॥ कुत एतत् ? ॥ लघ्वर्थं हि संज्ञाकरणम् । तत्र महत्याः संज्ञायाः करण एतत्प्रयोजनमन्वर्थसंज्ञा यथा विज्ञायेत अप्रधानमुपसर्जनमिति । प्रधानमुपसर्जनमिति च संबन्धिशब्दावेतौ । तत्र संबन्धादेतद्गन्तव्यम्—यं प्रति यदप्रधानं तं प्रति तदुपसर्जनसंज्ञं भवतीति ॥

(प्रदीपः) **महती संज्ञेति** । लोके चाप्रधानमुपसर्जनमुच्यते, इहापि तथैवाश्रीयत इत्यर्थः॥ यद्येवं पूर्वकायोर्द्धपिप्पली पुरुषव्याघ्र इत्यादिषु उपसर्जनसंज्ञा प्रधानस्य न प्राप्नोति ॥ नैष दोषः । अन्वर्थसंज्ञा हि यत्र सोर्थः सम्भवति तत्र प्रवृत्तिनिमित्तापेक्षाः प्रवर्तन्ते अन्यत्र तु विधानसामर्थ्यान्निरपेक्षाः, यथा कर्मप्रवचनीयसंज्ञा स्वत्यादीनामिति प्रथमानिर्देशसामर्थ्यादर्द्धादीनां संज्ञा प्रवर्तते ॥

(उद्द्योतः) अवयववृत्त्या सर्वनामादिपदैरिवानेनाभीष्टार्थालाभादाह—**लोके चेति** । संज्ञामहत्त्वमेतत्पदरूढ्यर्थभूतलौकिकार्थापरित्यागे हेतुरिति भावः ॥ अप्रधानस्यैव संज्ञित्वेऽव्याप्तिं शङ्कते—**यद्येवमिति ॥ पुरुषव्याघ्र इति** । इदमुदाहरणं चिन्त्यम् । **पर**वल्लिङ्गसूत्रस्थतत्पुरुषग्रहणप्रत्याख्यानपरेण भाष्येण तस्योत्तरपदार्थप्रधानतामननात् ॥ ननु संज्ञाविधानमेव कथं तत्प्रयोजकाभावेऽत आह—**प्रथमानिर्देशेति । 'पूर्वापराधरोत्तरम्' 'अर्धमिति ॥** एतेन प्रदेशेष्वन्वर्थत्वेनैव व्यवहारोपपत्तौ संज्ञाविधानं व्यर्थं स्यादित्यपास्तम् ॥ निर्विभक्तिकस्योच्चारणासंभवात्प्राथम्याच्च लघुत्वाच्च तन्निर्देशस्य सत्त्वेन तत्सामर्थ्यं चिन्त्यम् ॥ भाष्ये—**प्रधानमुपसर्जनमिति च संबन्धिशब्दाविति** । तत्र प्रधानमिति दृष्टान्तार्थं तद्वदुपसर्जनशब्दस्तत्प्रतिद्वन्द्व्यप्रधानार्थकत्वात्सम्बन्धिशब्द इति भावः॥ तदाह—**यं प्रतियदिति** । समासे प्रथमानिर्दिष्टमप्रधानत्वसमानाधिकरणोपसर्जनपदाभिन्नमिति सूत्रार्थः । एवं च प्रत्यासत्त्या यन्निरूपितमप्रधानत्वं तन्निरूपितमेवोपसर्जनसंज्ञाकार्यं पूर्वनिपात इत्यर्थः । ह्रस्वोपि न, यं प्रत्यप्रधानत्वं तद्घटितसमासोत्तरपदभूतस्यैव ह्रस्वविधानात् ॥

(आक्षेपभाष्यम्)

अथ यत्र द्वे षष्ठ्यन्ते कस्मात्तत्र प्रधानस्योपसर्जनसंज्ञा न भवति । राज्ञः पुरुषस्य राजपुरुषस्येति ।

(प्रदीपः) **अथ यत्रेति** । परिहारान्तरसद्भावादेतदुच्यते । अन्वर्थाश्रयणेन ह्येतदपि सिध्यति ॥

(उद्द्योतः) परे तु यं प्रतीत्यादिभाष्यस्यायमर्थः—समासशास्त्रे यन्निरूपितं यस्याप्राधान्यं तं प्रति तदुपसर्जनमिति । समासशास्त्रे च सहार्थतृतीयान्तार्थापेक्षया प्रथमान्तार्थस्याप्रधानत्वमिति तं प्रत्येव तदुपसर्जनम् । यद्यपि सहार्थविशेषणत्वरूपमप्राधान्यं तृतीयान्तार्थस्य, तथापि तत्समभिव्याहृतप्रथमाद्यन्तार्थस्य तदपेक्षया लौकिकमप्रधानत्वमितराधीनत्वरूपं बुध्यते । अत एव समकक्षयोर्मध्ये 'एकेन सह त्वया गन्तव्य' मित्युक्ते परस्य दुःखं दृश्यते ॥ पूर्वकायासिद्ध्या कैयटोक्ततदाश्रयणमशक्यमित्याहुः ॥ इत्यभिप्रायेण भाष्ये अथ यत्रेति ॥ परिहारान्तरेत्यादिकैयटश्चिन्त्य एव ॥

(६६१ समाधानवार्तिकम् ॥ ६ ॥) :

॥*॥षष्ठ्यन्तयोश्चोपसर्जनत्वे उक्तम् ॥*॥

(भाष्यम्) **किमुक्तम् ? । *षष्ठ्यन्तयोः समासे अर्थाभेदात् प्रधानस्यापूर्वनिपातः* इति । एवं न चेदमकृतं भवति "उपसर्जनं पूर्वम्" इति । अर्थश्चाभिन्न इति कृत्वा प्रधानस्य पूर्वनिपातो न भविष्यति ॥**

(प्रदीपः) **षष्ठ्यन्तयोश्चेति** । पूर्वनिपातप्रकरण इदमुक्तम् । तत्र हि पूर्वनिपातः प्रत्याख्यायते—***न वाऽनिष्ठादर्शनात्*** इति । अथाप्यारभ्यते तथापि राजशब्दस्यैव पूर्व-

निपातो न पुरुषशब्दस्य। एवं हि वाक्यापेक्षया समासस्यैकार्थता भवति अन्यथा वाक्यसमासयोर्भिन्नार्थता स्यादित्यर्थः। तथा हि। पुरुषार्थो राजापेक्षया प्रधानमेवात्रेति नासौ भिद्यते राजापेक्षया न व्यतिरिच्यते इत्यर्थः। ततोऽप्रधानस्यैवात्र राज्ञः पूर्वनिपातः॥

(उद्द्योतः) उपसर्जनसंज्ञाप्रयोज्यत्वं पूर्वनिपातस्य नास्तीति दर्शयितुं पूर्वनिपातप्रकरणप्रत्याख्यानमनुवदति—तत्र हीति। एवं हि तत्र भाष्यम्—उपसर्जनस्य पूर्ववचनं परप्रयोगनिवृत्त्यर्थम्* न वाऽनिष्टादर्शनात्*। अथ यत्र द्वे षष्ठ्यन्ते कस्मात्तत्र प्रधानस्य पूर्वनिपातो न भवतीत्याशङ्कायां* षष्ठ्यन्तयोः समास इत्यादि*॥ अनिष्टेति। नित्येषु शब्देषु प्रयोगे भिन्न गाव्यादिप्रयोगनिवारणाय शास्त्रम्, इह तु पुरुषराजेति प्रयोगो न दृश्यत इति किं तन्निवृत्त्यर्थेन यत्नेनेत्यर्थः॥ अबुधबोधनाय तदारम्भे पूर्वपक्षिणाशङ्कितस्य राज्ञः पुरुषस्येत्यादौ पूर्वनिपातितानियमदोषस्योद्धारपरं षष्ठ्यन्तयोरिति वार्तिकम् तद्व्याचष्टे—तथापीति। पुरुषस्य पूर्वनिपाते हि राज्ञः प्राधान्यमेव स्यात्पुरुषराजशब्दात्तथैव प्रतीतेरिति वाक्यसमासयोर्भिन्नार्थतेति भावः॥ नासौ भिद्यत इति। वाक्यात्समासे इति शेषः, पूर्वनिपाते हि तस्याप्राधान्यं प्रतीयेतेति भावः॥ तदेवाह—न व्यतिरिच्यत इति। व्यतिरेको विशेषणत्वं, तेद्धान्भवतीत्यर्थः॥ परे तु—ननु प्रधानस्य पूर्वनिपातेऽप्यर्धपिप्पलीत्यादौ न वाक्यसमासयोर्भिन्नार्थतेत्यतो भाष्यं प्रकारान्तरेण व्याचक्षते—षष्ठीति सूत्रे येन समासस्तन्निरूपितसंबन्धार्थकषष्ठ्यन्तमेव गृह्यते, तदेव च तत्र प्रथमानिर्दिष्टम्। पुरुषपदे च न राजापेक्षभेदसंबन्धे षष्ठी, तस्या विशेषणादेवोत्पत्तेरित्यर्थः॥ अर्थश्चाभिन्न इति भाष्यस्य प्रधानोऽर्थो न समासघटकविशेषणेन भेदमूलकसंबन्धवानतः प्रधानस्य तादृशषष्ठ्यन्तत्वाभावादनुपसर्जनत्वेनापूर्वनिपातः। कैयटरीत्या तु प्रधानपक्षकापूर्वनिपातानुमाने हेतोर्वैयधिकरण्यम्। उपसर्जनसंज्ञा न भविष्यतीत्यनेन पूर्वनिपाताभावः प्रधानस्यैतन्मूलक एव तत्रापीति सूचितम्। किं च कैयटरीत्या व्याख्याने न प्रयोजनानुवर्तिप्रमाणमिति न्यायविरोधः। कैयटोपि वा एवमेव व्याख्येयः। एवं च पुरुषापेक्षयाऽप्रधानस्यैव राज्ञः षष्ठ्यन्तस्य प्रथमानिर्दिष्टत्वमस्मिन्समास इति तस्यैवोपसर्जनत्वेन पूर्वनिपात इति भावः॥

(आक्षेपभाष्यम्)

यद्यपि तावदेतदुपसर्जनकार्यं परिहृतम्, इदमपरं प्राप्नोति राज्ञः कुमार्याः राजकुमार्याः "गोस्त्रियोरुपसर्जनस्य" इति ह्रस्वत्वं प्राप्नोति।

(६६२ समाधानवार्तिकम् ॥ ७ ॥)

॥ * ॥ उक्तं वा ॥ * ॥

(भाष्यम्) **किमुक्तम्? ॥ *परवल्लिङ्गमिति शब्दशब्दार्थौ* इति। तत्रौपदेशिकस्य ह्रस्वत्वम्, आतिदेशिकस्य श्रवणं भविष्यति ॥ प्रथमानिर्दिष्टं समास उपसर्जनम् ॥ ४३ ॥**

(प्रदीपः) शब्दशब्दार्थाविति। नन्वेतत्तत्र प्रत्याख्यातं परमयुवतिरित्यादौ द्वौ तिशब्दौ स्यातामिति। एवं तर्हि अन्वर्थाश्रयेणास्य परिहारस्योक्तत्वादत्र सूक्ष्मेक्षिका न कृता॥ ४३॥

(उद्द्योतः) राजकुमार्या इत्यादौ ह्रस्वत्वमपि अनेन वारितमिति सूचयन् आह—उक्तं वेति विकल्पार्थवाशब्दघटितम्। अन्यथा तदसंगतिः॥ सूक्ष्मेक्षिकेति। अर्धपिप्पल्यादौ तु गतिरुक्तैवेति भावः॥ ४३॥

(९६ उपसर्जनसंज्ञासूत्रम् ॥ १।२।१ आ. २८ सू.)

११८ एकविभक्ति चापूर्वनिपाते ॥ १। २। ४४ ॥

(प्रदीपः) **एक ॥ ४४॥ समास इति वर्तते। मुख्य एव चेह समासो गृह्यते समासे विधातव्ये यदेकविभक्तीति, समासार्थं वा वाक्यं समासो गृह्यते सर्वस्य च शब्दस्यैकविभक्तित्वमिति विशेषणोपादानसामर्थ्याद्यस्य पर्यायेणापि न सर्वविभक्तित्वं तदुपसर्जनसंज्ञं यथा निष्कौशाम्बिरित्यत्र कौशाम्बीशब्दो निष्क्रमणक्रियापेक्षयापादानशक्तिसम्बन्धात् पञ्चम्यन्त एव। नह्यस्य क्रियान्तरापेक्षः शक्त्यन्तराविर्भावः॥**

(उद्द्योतः) एकविभक्ति चा ॥ ४४ ॥ स्पष्टप्रतिपत्तये सूत्रार्थं दर्शयति—समास इति। समासार्थं वेति। अस्यैवापेक्षया बहिरङ्गक्रियाध्याहारालक्षणां युक्तां मन्यते॥ शास्त्रं तु न गृह्यते, एकविभक्तीत्यस्य वैयर्थ्यापत्तेः॥ सर्वस्य चेति। एकस्मिन् प्रयोगे इत्यादिः॥

(प्रथमानिर्दिष्टस्य पूर्वनिपातसाधकाधिकरणम्)

(आक्षेपभाष्यम्)

द्वितीयादीनामप्यनेनोपसर्जनसंज्ञा प्राप्नोति॥ तत्र को दोषः?॥ तत्रापूर्वनिपात इति प्रतिषेधः प्रसज्येत॥

(प्रदीपः) **द्वितीयादीनामिति**। कष्टश्रितादिषु कष्टादयः श्रितादिविशेषणत्वादेकविभक्तिका इत्यनेनोपसर्जनसंज्ञा तेषां प्राप्नोति। ततश्चापूर्वनिपात इति प्रतिषेधः प्राप्नोति। पूर्वसूत्रस्य तु नीलोत्पलादिः समानाधिकरणसमासोऽवकाशः॥

(उद्द्योतः) **श्रितादिविशेषणत्वादिति**। कर्माकाङ्क्षश्रितादिविशेषणत्वादित्यर्थः॥ ननु निरवकाशपूर्वप्राप्त्या इयं प्राप्तिर्बाध्येतात आह—**पूर्वसूत्रस्य त्विति**॥

(६६३ समाधानवार्तिकम् ॥ १ ॥)

॥ * ॥ नाप्रतिषेधात् ॥ * ॥

(भाष्यम्) **नायं प्रसज्यप्रतिषेधः—"पूर्वनिपाते**

न" इति ॥ किं तर्हि ?॥ पर्युदासोयम्—'यदन्यत्पूर्वनिपातादिति। पूर्वनिपाते अव्यापारः। यदि केनचित्प्राप्नोति तेन भविष्यति। पूर्वेण च प्राप्नोति तेन भविष्यति ॥

(६६४ समाधानवार्तिकम् ॥ २ ॥)

॥ * ॥ अप्राप्तेर्वा ॥ * ॥

(भाष्यम्) अथवा अनन्तरा या प्राप्तिः सा प्रतिषिध्यते॥ कुत एतत्?॥ 'अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा' इति। पूर्वा प्राप्तिरप्रतिषिद्धा तया भविष्यति॥

(आक्षेपभाष्यम्)

ननु चेयं प्राप्तिः पूर्वां प्राप्तिं बाधते॥

(प्रदीपः) ननु चेयमिति। प्रतिषेधयुक्तत्वायुक्तत्वेन विरोधात्परत्वादिति भावः॥

(समाधानभाष्यम्)

नोत्सहते प्रतिषिद्धा सती बाधितुम्॥

(प्रदीपः) नोत्सहत इति। अपवादविषयं प्रकल्प्योत्सर्गस्य प्रवर्तनात्॥

(उद्द्योतः) अपवादेति। अपूर्वनिपात इति हि सः॥

(६६५ आक्षेपवार्तिकम् ॥ ३ ॥)

॥*॥ एकविभक्तावषष्ठ्यन्तवचनम्॥ *॥

(भाष्यम्) एकविभक्तावषष्ठ्यन्तानामिति वक्तव्यम्। इह मा भूत्—अर्धं पिप्पल्याः अर्धपिप्पलीति॥

(उद्द्योतः) भाष्ये—एकविभक्ताविति। शब्दशब्दार्थाविलस्य प्रत्याख्याने इदं वचनमेव कर्तव्यम्॥ एकदेशिसमासविषयकमेव तद्, भाष्ये तथोदाहरणात्॥

(६६६ समाधानवार्तिकम् ॥ ४ ॥)

॥ * ॥ उक्तं वा ॥ * ॥

(भाष्यम्) किमुक्तम्। *परवल्लिङ्गमिति शब्दशब्दार्थौ* इति तत्रौपदेशिकस्य ह्रस्वत्वम् आतिदेशिकस्य श्रवणं भविष्यति॥

(आक्षेपभाष्यम्)

कानि पुनरस्य योगस्य प्रयोजनानि?॥

(६६७ प्रयोजनवार्तिकम् ॥ ५ ॥)

॥ * ॥ प्रयोजनं द्विगुप्राप्तापन्नालंपूर्वोपसर्गाः ॥ * ॥

(भाष्यम्) कार्ये द्विगुः—पञ्चभिर्गोभिः क्रीतः पञ्चगुः। दशगुः॥

प्राप्तापन्न[पूर्वे]—प्राप्तो जीविकां प्राप्तजीविकः। आपन्नो जीविकामापन्नजीविकः॥

अलंपूर्वे—अलं कुमार्यै अलंकुमारिः॥

उपसर्गाः कार्ये-निष्कौशाम्बिः निर्वाराणसिः॥ एकविभक्ति०॥ ४४॥

इति श्रीमद्भगवत्पतञ्जलिविरचिते व्याकरणमहाभाष्ये प्रथमस्याध्यायस्य द्वितीयपादे प्रथमाह्निकम्॥

(प्रदीपः) पञ्चगुरिति। *द्विगुप्राप्तापन्नालंपूर्वगतिसमासेषु प्रतिषेधो वक्तव्यः* इति वचनात्परवल्लिङ्गं न भवति॥ अलंकुमारिरिति। * पर्यादयो ग्लानाद्यर्थे चतुर्थ्येति समासः॥ ४४॥

इत्युपाध्यायजैयटात्मजकैयटकृते महाभाष्यप्रदीपे प्रथमस्य द्वितीये पादे प्रथमाह्निकम्॥

(उद्द्योतः) नन्वेवमपि प्राप्तजीविक इत्यादौ परवल्लिङ्गं स्याद् एवं स्त्रीगोभ्यक्तिभिः क्रीतपदेषु पञ्चगूनितीष्यते न च सिध्यतीत्यत आह—द्विगुप्राप्तेति। वस्तुतो द्विगुग्रहणं परवदित्यस्यान्तरङ्गत्वेन तत्पुरुषसंज्ञकशब्दमात्रनिमित्तकलिङ्गबाधकताया एव युक्तत्वाद् व्यर्थमिति बोध्यम्॥ पर्यादय इति। कुगतीति सूत्रे आदिशब्दस्य प्रकारार्थत्वादिति भावः॥ अलंशब्दयोगे चतुर्थीविधानसामर्थ्याद्वा-ऽयमपीत्याहुः॥ ४४॥

इति श्रीशिवभट्टसुतसतीगर्भजनागोजीभट्टकृते भाष्यप्रदीपोद्द्योते प्रथमस्य द्वितीये प्रथमाह्निकम्॥

आदितो दशममाह्निकम्॥

प्रथमाध्याये द्वितीये पादे द्वितीयाह्निकम्।

(आदित एकादशमाह्निकम्)

(९७ प्रातिपदिकसंज्ञासूत्रम् ॥ १। २। २ आ. १ सू०)

११९ अर्थवदधातुरप्रत्ययः प्रातिपदिकम्॥ १। २। ४५॥

(पदकृत्यनिरूपणाधिकरणम्)

(आक्षेपभाष्यम्)

[अर्थवद्ग्रहणं किमर्थम्?।]

(समाधानभाष्यम्)

अर्थवदिति व्यपदेशाय। वर्णानां मा भूदिति॥ किं च स्यात्?॥ वनं धनमिति "नलोपः प्रातिपदिकान्तस्य" इति नलोपः प्रसज्येत॥

(प्रदीपः) **अर्थवदधातुरप्रत्ययः प्रातिपदिकम्** ॥ ४५ ॥ अभिधेयवचनोत्रार्थशब्द आश्रीयते। तत्राधातुरप्रत्यय इति पर्युदासाश्रयणादर्थवत एव संज्ञा भविष्यति नार्थोर्थवद्ग्रहणेनेत्याशङ्क्याह—**अर्थवदिति व्यपदेशायेति**। संज्ञिन इति वाक्यशेषः॥ पर्युदासाश्रयणे केन धर्मेण सादृश्यमाश्रीयत इत्यप्रतिपत्तिः स्यादिति भावः॥ **वर्णानां मा भूदिति**॥ विशिष्टसंज्ञिव्यपदेशफलं दर्शयति॥ क्वचिद्वर्णानां चेति पाठः। तत्र चशब्देन पदसमुदायोनर्थको **दश दाडिमानी**त्यादिः समुच्चीयते॥ **किं च स्यादिति**। संख्याकर्मादिषु स्वादीनां विधानादनर्थकेभ्यः स्वाद्युत्पत्तिर्न भविष्यतीति प्रश्नः॥ **वनमिति**॥ नन्वधातुरिति नान्तस्य प्रतिषेधो भविष्यति॥ नैतदस्ति। प्रतिवर्णमत्र विभक्त्युत्पत्तिप्रसङ्गः। न च प्रतिवर्णं धातुसंज्ञासमावेशः। अयं भावः—अविशेषेण स्वादय उत्पद्यन्ते तेषूत्पन्नेष्वर्थनियमः प्रकृतार्थापेक्षया वा प्रत्ययनियम इति स्यादेव स्वाद्युत्पत्तिः। अव्ययादिव॥ यदुक्तम्—*संघातस्यैकार्थ्यात्सुबभावो वर्णात्* इति, तद्वर्णानामर्थवत्तापक्षे। तत्र हि तत्रैकैव विभक्तिः समुदायावयवार्थगतमेकत्वं प्रत्याययिष्यति। एकमेव हि तदेकत्वम्। तच्चैकेनैव हि सुपा प्रत्यायितमित्यवयवेभ्यो विभक्तिर्न स्यात्॥ अनर्थकस्य तु प्रातिपदिकसंज्ञायां प्रकाशयितव्यस्यार्थस्याभावात्समुदायादिव प्रतिवर्णं विभक्त्युत्पत्तिप्रसङ्गः॥ **नलोप इति**। विभक्तेस्तु श्रवणं न भवति, समुदायस्य पृथक् प्रातिपदिकसंज्ञायां तदन्तर्भावाद् लुको भावाद्। नलोपस्योपलक्षणार्थत्वाज्जश्त्वादीनामपि प्रसङ्गः॥

(उद्द्योतः) **अर्थवदधातु** ॥ ४४ ॥ अभिधेयेति। सर्वशब्दानां प्रयोजनवत्त्वेनाव्यभिचारात् प्रयोजनवाचिनोऽसंभवाच्च धनवाचिनो ग्रहणाभावादिति भावः॥ कस्येत्याकाङ्क्षायामाह—**संज्ञिन इति। व्यपदेशो** विशिष्टसंज्ञिनो लाभः॥ **केनेति**। शब्दत्वादिनापि तदाश्रीयेतेति भावः॥ **नञिवयुक्त**न्यायानित्यत्वज्ञापकं तदित्यन्ये॥ चश्रवणाद् व्यपदेशापेक्षया भिन्नमेतत्फलमिति भ्रमनिवृत्तये आह—**विशिष्टेति**। चपाठस्तु प्रामादिक इति भावः॥ तमपि समर्थयते—**क्वचिदिति**॥ समासग्रहणं त्वर्थवत्समुदायस्यैव नियामकमिति भावः॥ **संख्येति**। '**द्व्येकयोः**' '**कर्मणी**'त्यादीनां स्वादिविध्येकवाक्यत्वादिति भावः॥ एवं च कार्याभावात्संज्ञापि न स्यादिति तात्पर्यम्॥ **न च प्रतीति**। क्रियावचनत्वाभावादिति भावः॥ ननूक्तरीत्या स्वाद्यनुत्पत्तौ कथं पदत्वनिबन्धनो नलोपोऽत आह—**अयं भाव इति**॥ **उत्पन्नेष्विति**। उत्पन्नस्यापि लुगादिनेव निवृत्तिरित्यर्थः॥ एकस्मिन्नेकवचनमिति सामान्यापेक्षप्रत्ययनियमे कस्या अप्यनवस्थितेराह—**अर्थनियम इति**। अनेकप्रकरणव्यवधानादेकवाक्यतापक्षो दुर्बल इत्यभिमानः॥ प्रत्ययनियमेपि न दोष इत्याह—**प्रकृतेति**। संनिहितेत्यर्थः॥ अवश्यमेवमाश्रयणीयमित्याह—**अव्ययादिवेति**॥ **यत्तूक्तमिति**। हयवरट्सूत्रे इति शेषः॥ **प्रकाशयितव्यस्यार्थस्याभावादिति**। तदभावेपि प्रातिपदिकसंज्ञासामर्थ्यादित्यर्थः॥ **समुदायादिवेति**। अनर्थकनिपातरूपात्समुदायादिवेत्यर्थः॥ वस्तुतः संख्याकर्मादेरभावाद्विभक्तेरत्रानुत्पत्तिरेव। अर्थनियमादिप्रकारास्तु महासंज्ञाविरोधाद् गमके सत्येव, न सर्वत्र। एतद्व्यावर्त्यं तु निरर्थकसमुदाय इति बोध्यम्॥ ननु सर्वसुबुत्पत्तौ तेषां श्रवणापत्तिः सर्वैकवचनोत्पत्तावपि एवमेवात आह—**विभक्तेस्त्विति**॥ **समुदायस्येति**। कृदन्तस्यान्तरङ्गत्वादवयवसंज्ञा—तन्निमित्तसुप्प्रवृत्तिकालोत्तरकाले इत्यर्थः। समासनियमस्त्वर्थवत्समुदायविषय इति भावः॥ न च धनतीत्यादौ प्रतिवर्णं सुबुत्पत्तौ तच्छ्रवणप्रसङ्ग इति वाच्यम्। धातुप्रत्ययपदयोर्धात्ववयवप्रत्ययान्तावयवपरतया तत्र सर्वत्र वारणेनादोषात्॥ तस्मादव्युत्पन्नप्रातिपदिकावयववर्णानां संज्ञैवापाद्या, तत्र च समुदायप्रातिपदिकावयवत्वेन तल्लोपः धनवनादिकमव्युत्पन्नमिति भावस्तद्ध्वनयन्नाह—**जश्त्वादीनामिति**। एतेन जश्त्वादौ धकाराद्युच्चारणवैयर्थ्यमित्यपास्तम्॥

(आक्षेपभाष्यम्)

अधातुरिति किमर्थम्?॥

(समाधानभाष्यम्)

'अहन् वृत्रम्'॥

(प्रदीपः) **अहन्निति**। विशेषविहितत्वाल्लङाद्युत्पत्तौ सत्यामडागमस्य धातुभक्तत्वात्प्रातिपदिकसंज्ञायां सत्यां नलोपप्रसङ्गः। न चाप्रत्यय इति प्रत्ययलक्षणेन प्रतिषेधः। **न ङिसंबुद्ध्योरि**ति ज्ञापनाद् नलोपे विधीयमाने प्रत्ययलक्षणेनाप्रत्यय इति निषेधाभावात्॥

(उद्द्योतः) **विशेषेति**। अनवकाशत्वात् सुपं बाधित्वेति भावः। न च श्येनायत इत्यादौ लङादयः सावकाशा इति, अत्र परत्वात् सुबुत्पत्तिर्दुर्वारा। एवं तर्हि भूवादिसूत्रस्य यल्लङादिविधावुपस्थानं तस्यानवकाशत्वादित्यर्थः॥ **अडागमस्येति**। अङ्गभक्तत्वेपि धातुरेवात्राङ्गमिति धातुभक्तत्वादित्युक्तम्॥ इदं च स्वरूपकथनम् **न ङिसंबुद्ध्योरिति**। कथमन्यथा राजेत्यादौ नलोपः। न च कृदन्तत्वात्सिद्धिः, तत्राप्यप्रत्यय इत्यनुवृत्तेरिति भावः॥

(समाधानबाधकभाष्यम्)

अधातुरिति शक्यमवक्तुम्॥

(आक्षेपभाष्यम्)

कस्मान्न भवति 'अहन्नृत्रम्' इति ? ॥

(समाधानभाष्यम्)

आचार्यप्रवृत्तिर्ज्ञापयति—न धातोः प्रातिपदिकसंज्ञा भवति—इति, यदयं "सुपो धातुप्रातिपदिकयोः" इति धातुग्रहणं करोति ॥

(प्रदीपः) धातुग्रहणं करोतीति । पुत्रीयतीत्यादौ प्रातिपदिकत्वादेव लुक् सिद्ध इति भावः ॥

(उद्द्योतः) पुत्रीयतीति । अप्रत्यय इति प्रत्ययस्यैव निषेध इत्यभिमानः ॥

(समाधानसाधकभाष्यम्)

नैतदस्ति ज्ञापकम् । प्रतिषिद्धार्थमेतत्स्यात्—अपि काकः श्येनायत इति ॥

(प्रदीपः) श्येनायत इति । अत्राप्रत्यय इति निषिद्धा प्रातिपदिकसंज्ञा ॥

(उद्द्योतः) प्रत्ययान्तस्य स निषेध इत्यभिप्रायेणाह—अत्राप्रेति ॥

(आक्षेपभाष्यम्)

अप्रत्यय इति किम् ? ॥

(समाधानभाष्यम्)

काण्डे कुड्ये ॥

(उद्द्योतः) भाष्ये—काण्ड इति । परादिवद्भावेन प्रत्ययान्तत्वमिति भावः ॥ न च पर्युदासे शाब्दफललाभायान्तवत्त्वस्यैव प्रवृत्तेस्तेनाप्रत्ययान्तत्वात्प्रातिपदिकत्वं स्यादेव, तथा च ह्रस्वः स्यादिति वाच्यम् । भाष्यकृता वक्ष्यमाणत्वात् ॥

(समाधानबाधकभाष्यम्)

अप्रत्यय इति शक्यमवक्तुम् ॥

(आक्षेपभाष्यम्)

कस्मान्न भवति काण्डे कुड्य इति ? ॥

(समाधानभाष्यम्)

कृत्तद्धितग्रहणं नियमार्थं भविष्यति—कृत्तद्धितान्तस्यैव प्रत्ययान्तस्य प्रातिपदिकसंज्ञा भवति, नान्यस्येति ॥

(प्रदीपः) कृत्तद्धितग्रहणमिति । तद्धितग्रहणमत्र नियमार्थम्, कृद्ग्रहणं तु प्रतिषिद्धार्थं भिद् छिदिति । अत्र अधातुरिति प्रतिषेधप्रसङ्गः ॥

(उद्द्योतः) अत्र हीति । न च कृद्ग्रहणस्य प्रतिषेधबाधनार्थत्वे तद्धितग्रहणनियमात्कारकशब्दे प्रातिपदिकत्वानापत्तिः, कृद्ग्रहणं तु अपेक्षावादन्यायेनाधातुरितिप्रतिषेधस्यैव बाधकः स्यादिति वाच्यम् । बाध्यसामान्यचिन्ताश्रयणादित्यभिमानः ॥ वस्तुतो धातोः प्रत्ययान्तस्य च चेत्कृत्तद्धितान्तस्यैवेतिनियमे भाष्यतात्पर्यं, तेनाधातुग्रहणमपि प्रत्याख्यातम् । क्विबाद्यन्तस्यापि प्रत्ययान्तत्वात् प्रत्ययान्तस्येत्येवं भाष्ये उक्तम् । न चास्यापत्यमिरित्यादौ प्रत्ययलक्षणप्रयुक्तनिषेधबाधनार्थं तद्धितस्यैव संज्ञाविधानमस्त्विति वाच्यम् । तस्य निषेधे फलाभावात् । न च इरिष्वित्यादौ सोः प्रातिपदिकत्वापत्तिः, एवं चौत्सर्गिकैकवचनापत्तिः, सात्पदाद्योरिति षत्वनिषेधापत्तिश्चेति वाच्यम् । औत्सर्गिकस्यापि विना गमकमप्रवृत्तेः ॥

(अनिष्टापत्तिवारणाधिकरणम्)

(६६८ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ अर्थवत्यनेकपदप्रसङ्गः ॥ * ॥

(भाष्यम्) **अर्थवदिति प्रातिपदिकसंज्ञायामनेकस्यापि पदस्य प्रातिपदिकसंज्ञा प्राप्नोति—'दश दाडिमानि, षडपूपाः, कुण्डमजाजिनं पललपिण्डः अधरोरुकमेतत्कुमार्याः स्फैयकृतस्य पिता प्रतिशीन' इति ॥**

(प्रदीपः) अनेकपदप्रसङ्ग इति । अनेकं पदमस्मिन्नित्यनेकपदः समुदायस्तस्य संज्ञाप्रसङ्ग इत्यर्थः ॥ अनेकस्यापि पदस्येति । समुदितस्येति बोद्धव्यम् । प्रतिपदं तु नैव संज्ञा प्राप्नोत्यप्रत्यय इति निषेधात् । समुदायस्य तु निषेधो न प्रवर्तते 'प्रत्ययग्रहणे यस्मात्स विहित इति वचनात्समुदायाच्च प्रत्ययस्याविधानात् प्रत्ययान्तत्वाभावात् । न विद्यते प्रत्ययो यस्मिन्सोयमप्रत्यय इत्यप्याश्रयितुं न युज्यते, बहुपटव इत्यस्यापि समुदायस्य निषेधप्रसङ्गात् । स्वरे दोषप्रसङ्गाच्च ॥

(उद्द्योतः) बहुव्रीहावनेकस्यापि पदस्येति भाष्यानुपपत्तेराह—समुदितस्येति । अत एवानेकग्रहणं चरितार्थम् ॥ बहुव्रीह्याश्रयणस्य फलं दर्शयति—प्रतिपदं त्विति ॥ प्रत्ययान्तत्वाभावादिति । संज्ञाविधावितिनिषेधस्तु नात्र, यत्र प्रत्ययस्य संज्ञा तत्रैव तन्निषेधप्रवृत्तेरिति भावः ॥ स्वरे दोषेति । अनुपदमेव स्फुटीभविष्यत्येतत् ॥

(समाधानभाष्यम्)

समुदायोऽत्रानर्थकः ॥

(प्रदीपः) समुदायोऽत्रानर्थक इति । पदार्थानां समन्वयाभावात् ॥

(उद्द्योतः) समन्वयेति । स एव हि वाक्यशक्यः ॥

(६६९ समाधानबाधकवार्तिकम् ॥ २ ॥)

॥ * ॥ समुदायोनर्थक इति चेदवयवार्थवत्त्वात्समुदायार्थवत्त्वं यथा लोके ॥ * ॥

(भाष्यम्) **समुदायोनर्थक इति चेदवयवार्थवत्त्वात्समुदायार्थवत्त्वम् । अवयवैरर्थवद्भिः समु-**

दाया अर्थवन्तो भवन्ति ॥ यथा लोके । तद्यथा लोके—आढ्यमिदं नगरं गोमदिदं नगरमित्युच्यते । न च सर्वे तत्राढ्या भवन्ति, सर्वे वा गोमन्तः ॥

(प्रदीपः) अवयवार्थवत्त्वादिति । अवयवधर्माणां च समुदाये व्यपदेशात्, सति च प्रातिपदिकत्वे लुग्लुक्प्रसङ्गः ॥

(उद्द्योतः) अवयवधर्माणामिति । यथा ग्रामो दग्ध इत्यादौ ॥

यथा लोके इत्युच्यते, लोके चावयवा एवार्थवन्तो न समुदायाः । अतश्चावयवा एवार्थवन्तो न समुदायाः । यस्य हि यद्द्रव्यं भवति स तेन कार्यं करोति । यस्य च या गावो भवन्ति स तासां क्षीरं घृतमुपभुङ्क्ते । अन्यैरेतद् द्रष्टुमप्यशक्यम् ॥

(युक्तिप्रश्नभाष्यम्)

का तर्हीयं वाचोयुक्तिराढ्यमिदं नगरं गोमदिदं नगरमिति ? ॥

(युक्तिप्रदर्शनभाष्यम्)

एषैषा वाचोयुक्तिः । इह तावदाढ्यमिदं नगरमित्यकारो मत्वर्थीयः—आढ्या अस्मिन्सन्ति तदिदमाढ्यमिति । गोमदिदं नगरमिति मत्वन्तात् मत्वर्थीयो लुप्यते ॥

(प्रदीपः) एषैषेति । एषा या वाचोयुक्तिः सैषा एतत्प्रमाणेत्यर्थः ॥ अकारो मत्वर्थीय इति । ततश्च नावयवधर्मेण समुदाये व्यपदेशः । किं तर्हि ? दण्ड्यादिवद्यौगिक इत्यर्थः ॥ मत्वन्तादिति । मत्वन्तान्मतुन्न भवति, सरूपः प्रत्ययो नेष्ट इति वचनात् । तस्मादेकगोपूर्वादिति ठञो भाष्यकारवचनप्रामाण्याल्लोपः । अत इति च तत्र निवृत्तं गौत्रिकादिसिद्ध्यर्थं, गवां समूहो गोत्रा, सास्मिन्नस्तीति गौत्रिकम् ॥ अथ वा मत्वन्तान्मत्वर्थीयो लुप्यत इत्यनेनावयवधर्मस्य समुदाये उपचारमाह । इह तु मुख्येऽर्थवत्त्वे सम्भवत्युपचरितस्याश्रयो न युक्तः ॥

(उद्द्योतः) वीप्साया निष्प्रयोजनत्वादाह—एषा येति । नैवात्र वीप्सेति भावः ॥ मतुन्नेति । इदमेव ध्वनयितुं भाष्ये मत्वर्थीय इत्युक्तं मतुबिति नोक्तम् ॥ लुग्विधायकाभावादाह—भाष्यकारेति ॥ नन्वत इत्यनुवृत्तेरसाद्गव्, दुर्लभोत आह—अत इतीति ॥ गोत्रेत्यत्रेनिन्नकव्यचश्चेति त्रः ॥ एकपूर्वसाहचर्याद्गोपूर्वस्यापि समासस्यैव तत्र ग्रहणमिति मते आह—आदीति । आदिना गोशकटिप्रकृतिकगौशकटिकस्य ग्रहणम् ॥ अथ वेति । गम्यमानार्थस्य निवृत्तिरेव चादिलोप इति वल्लोपशब्देनोक्तेति भावः ॥ परे त्वेषा व्याख्या न भाष्यस्वरससिद्धा, अवयवार्थवत्त्वेन समुदायार्थवत्त्वाभावं प्रक्रम्यैतदुक्तेः । तस्मादर्शआद्यचस्तत्प्रामाण्याद्गुणवचनेभ्य इति मत्वर्थीयलोप इति सारम् । ग्रामो दग्ध इत्यादावप्यर्शआद्यजेव, अवयवे वा समुदायरूपारोप इति भाष्यतात्पर्यम् ॥

(आक्षेपशेषभाष्यम्)

एवमपि—

(६७० आक्षेपवार्तिकम् ॥ ३ ॥)

॥ * ॥ वाक्यप्रतिषेधोऽर्थवत्त्वात् ॥ * ॥

(भाष्यम्) वाक्यस्य प्रातिपदिकसंज्ञायाः प्रतिषेधो वक्तव्यः । देवदत्त गामभ्याज शुक्लां देवदत्त गामभ्याज कृष्णामिति ॥ किं कारणम् ? ॥ अर्थवत्त्वात् । अर्थवद्ध्येतद्वाक्यम् ॥

(प्रदीपः) अर्थवद्वाक्यमिदानीं दर्शयति—एवमपीति । अर्थवद्धीति । पदार्थानां समन्वयावगमात् ॥

(उद्द्योतः) भाष्येऽर्थवद्ध्येतद्वाक्यमिति पाठः ॥

(आक्षेपबाधकभाष्यम्)

न वै पदार्थादन्यस्यार्थस्योपलब्धिर्भवति वाक्ये ।

(प्रदीपः) न वै पदार्थादिति । पदानि स्वमर्थं प्रतिपादयन्ति वाक्यम् । पदार्था एव त्वाकाङ्क्षायोग्यतासन्निधिवशात् परस्परसंसृष्टा वाक्यार्थ इत्यर्थः । न तु वाक्यं वाक्यार्थो वा पृथगस्तीति भावः ॥

(उद्द्योतः) नन्वन्वयरूपोऽर्थः पदार्थातिरिक्त उपलभ्यतेऽत आह—पदानीति । पदार्था एव इत्यनेन संसर्गबोधे पदानां व्यापारो नास्तीति दर्शयति । एवं च पदार्थैरेवाकाङ्क्षादिभिः संसर्गस्य गम्यमानत्वान्न तत्र वाक्यशक्तिर्वाक्यस्यातिरिक्तस्याभावाच्च तदाह—नतु वाक्यमिति । वाक्यार्थो वेति । संसर्गस्य पदार्थबोध्यत्वादिति भावः ॥

(६७१ आक्षेपसाधकवार्तिकम् ॥ ४ ॥)

॥ * ॥ पदार्थादन्यस्यानुपलब्धिरिति चेत् पदार्थाभिसंबन्धस्योपलब्धिः [स्तस्मात्प्रतिषेधः] ॥ * ॥

(भाष्यम्) पदार्थादन्यस्यानुपलब्धिरिति चेद् । इदमुच्यते—पदार्थाभिसंबन्धस्योपलब्धिर्भवति वाक्ये । इह देवदत्त इत्युक्ते कर्ता निर्दिष्टः, कर्म क्रियागुणौ चानिर्दिष्टौ । गामित्युक्ते कर्म निर्दिष्टम्, कर्ता क्रियागुणौ चानिर्दिष्टौ । अभ्याजेत्युक्ते क्रिया निर्दिष्टा, कर्तृकर्मणी गुणश्चानिर्दिष्टः । शु-

क्लामित्युक्ते गुणो निर्दिष्टः, कर्तृकर्मणी क्रिया चानिर्दिष्टा । इहेदानीं देवदत्त गामभ्याज शुक्लामित्युक्ते सर्वं निर्दिष्टम्—देवदत्त एव कर्ता नान्यः । गामेव कर्म नान्यत् । अभ्याजैव क्रिया नान्या । शुक्लामेव न कृष्णामिति ॥ एषां पदानां सामान्ये वर्तमानानां यद्विशेषेऽवस्थानं स वाक्यार्थः ॥ तस्मात्प्रतिषेधः । तस्मात्प्रतिषेधो वक्तव्यः ॥

(प्रदीपः) पदार्थाभिसंबन्धस्येति । ध्वनिव्यङ्ग्यं नित्यं वाक्यं विशिष्टस्यार्थस्य पदार्थसंसर्गरूपस्य वाचकम् । अन्यथा ह्यशाब्दो वाक्यार्थः स्यात् ॥ कर्ता निर्दिष्ट इति । सम्बोधनविषयमनियतक्रियं कर्तृमात्रमित्यर्थः ॥ यद्विशेषेवस्थानमिति । पदार्थसंसर्गरूपे वाक्यार्थ इत्यर्थः । अत एव वाक्यमेव मुख्यः शब्दो वाक्यार्थ एव मुख्यः शब्दार्थः । सादृश्यात्त्वन्वयव्यतिरेकौ कल्पितौ लाघवार्थमाश्रित्य पदपदार्थव्यवस्थापनं क्रियते । प्रतिवाक्यं व्युत्पत्त्यसम्भवाच्छाब्दव्यवहाराभावप्रसङ्गात् ॥

(उद्द्योतः) ननु पदातिरिक्तवाक्याभावात्कस्य पदार्थाभिसंवन्धो वाच्यः स्यादत आह—ध्वनिव्यङ्ग्यमिति । अनेन स्थिरत्वं तस्य दर्शितम् ॥ विशिष्टस्यार्थस्येति । विशेषणत्वादिविशिष्टस्येत्यर्थः ॥ पदार्थानां संसर्गबोधकत्वे दोषमाह—अन्यथेति । न च शब्दप्रयोज्यत्वाच्छाब्दत्वम्, प्रत्यक्षदृष्टधूमबोध्यवह्नेरपि प्रत्यक्षत्वापत्तेः, श्रुतधूमशब्दोपस्थितधूमार्थबोध्यवह्नेरपि शाब्दत्वापत्तेश्च । यदि तु पदसमभिव्याहाररूपाकाङ्क्षा तत्कारणत्वज्ञानं च शाब्दबोधे कारणमिति शाब्दत्वं, तदा पदानां पदार्थेष्वपि शक्तिर्न सिध्येत् । तदुक्तम्—

अशाब्दो यदि वाक्यार्थः पदार्थोपि तथा भवेत् इति । यदि बोधजनकतयाऽसंबद्धे वक्तुमशक्यतया पदार्थैः पदानां शक्तिरूपसंवन्धकल्पनं तदा समभिव्याहारे संसर्गबोधकारणताया अपि असंबद्धे वक्तुमशक्यतया तेन तादात्म्यसंबन्धस्य वाक्ये आवश्यकत्वात् ॥ तादात्म्यमेव च शक्तिरिति तत्त्वम् ॥ पदार्थातिरिक्तः कश्चिद्वाक्यार्थोस्तीति वक्तुमुपक्रमते—भाष्ये इहेत्यादि ॥ ननु कर्तृत्वस्य क्रियानिरूपितत्वात् क्रियायाश्चासंनिधानात् तत्त्वाभावेन कर्तृत्वानुपपन्नमत आह—कर्तृमात्रमिति । प्रधानीभूतधात्वर्थमात्राश्रय इत्यर्थः । एवं कर्मशब्देन धात्वर्थफलमात्राश्रयः ॥ अनिर्दिष्टाविति । पूर्वत्र विभक्तिविपरिणामेनान्वयः । ईदृशप्रकारोपि भाष्यप्रामाण्यायुक्त एव । तृतीयस्थलेऽनिर्दिष्ट इत्येव पाठः ॥ देवदत्त एव कर्ता नान्य इति । अनेनैतद्दर्शयति यत्किंचित्कारकस्य क्रियाया वोच्चारणे सर्वक्रियाणां योग्यानां सर्वकारकाणां च योग्यानामाक्षेपो भवति । एवं च सर्वत्र वाक्यमेव बोधकं तत्तदुपादानं तु नियमायेति ॥ गामेव···नान्यदिति । गामिति शब्दवाच्यमेव कर्म नान्यदित्यादिक्रमेणार्थः ॥ भाष्ये सामान्ये सामान्य क्रियाकर्तृत्वादिविशिष्टे विशेषे विशेषणविशेष्यभावापन्ने ॥ तदाह—संसर्गरूपवित्यादि । विशेषणविशेष्यभावरूपसंसर्गेत्यर्थः । स एव वाक्यार्थ इति निरूपितं मञ्जूषायाम् ॥ अत एवेति । तेनैव लौकिकवैदिकव्यवहारादित्यर्थः ॥ नन्वेवं पदार्थव्यवहारोऽसङ्गतः स्यादत आह—सादृश्यादिति । लाघवार्थे कल्पितावन्वयव्यतिरेकावाश्रित्य सादृश्यात्पदपदार्थव्यवस्थेत्यन्वयः । यथा वर्णेष्वारोपिता उदात्तादयो व्यञ्जकध्वनिधर्मा व्यवहारे हेतवः । एवमिहापि काल्पनिकः पदपदार्थविभागस्तथेति भावः ॥ ननु सादृश्यकल्पना व्यर्थेत्यत आह—प्रतिवाक्यमिति ॥

(आक्षेपनिराकरणभाष्यम्)

न वक्तव्यः ।

(६७२ समाधानवार्तिकम् ॥ ६ ॥)

॥ * ॥ अर्थवत्समुदायानां समासग्रहणं नियमार्थम् ॥ * ॥

(भाष्यम्) अर्थवत्समुदायानां समासग्रहणं नियमार्थं भविष्यति । समास एवार्थवतां समुदायानां प्रातिपदिकसंज्ञो भवति नान्य इति ॥

(समाधानबाधकभाष्यम्)

यदि नियमः क्रियते प्रकृतिप्रत्ययसमुदायस्य प्रातिपदिकसंज्ञा न प्राप्नोति बहुपटवः उच्चकैर्नीचकैरिति ॥

(प्रदीपः) बहुपटव इति । द्योत्येनार्थेनार्थवान् प्रत्ययः । प्रकृतिस्तु वाच्येनेत्यर्थवत्समुदायोयं भवति ॥ उच्चकैरिति । तन्मध्यपतितस्तद्ग्रहणेन गृह्यत इति यदा नाश्रीयते, नापि *अकच्प्रभ्रत्वतः* इति, तदायं दोषः । तदा हि सुबन्तस्याकचि कृते अव्ययादिति सुब्लुगभावात्सुपो धातुप्रातिपदिकयोरिति लुगिष्यते, स च न प्राप्नोति ॥

(उद्द्योतः) ननु बह्वादीनां स्वार्थिकत्वेनार्थवत्त्वं नेत्यर्थवत्समुदायत्वमस्मिन् कथमत आह—द्योत्येनेति ॥ ननु तन्मध्यपतितन्यायेन *"अकजक्षम्वतः सर्वनामाव्ययविधौ*" इति येन विधिरिति सूत्रस्थवचनेन चाव्ययत्वात् लुक् सिद्ध इति किमत्र प्रातिपदिकत्वेनात आह—तन्मध्येति ॥ तदा हीति । तन्मध्यपतित इत्यादिन्यायाभावे इत्यर्थः ॥ अन्तरङ्गत्वाल्लुकृत्वाच्च पूर्वमेवाकचोऽव्ययादिति सुब्लुक् कुतो नेति चिन्त्यम् । बहुपटव उच्चकैर्नीचकैरिति वाक्ये बहुपटव इत्युदाहरणम् । किं पुनरिति प्रश्नाशयस्तु यथैवेत्यादिना वक्ष्यमाण इत्यन्ये ॥

(नियमवादिनः प्रश्नभाष्यम्)

किं पुनरत्र प्रातिपदिकसंज्ञया प्रार्थ्यते ? ॥

(प्रदीपः) किं पुनरत्रेति । उच्चकैरित्याद्यन्यथा सिध्यतीति प्रश्नः ॥

(उद्द्योतः) अन्यथा सिध्यतीति । तन्मध्यपतितादिन्यायेनेति भावः ॥

(इतरस्य दूषणप्रदर्शकभाष्यम्)

प्रातिपदिकादिति स्वाद्युत्पत्तिर्यथा स्यादिति ॥

(प्रदीपः) इतरो बहुपटव इति न सिध्यतीति मन्यमान आह—प्रातिपदिकादिति ॥

(नियमवादिनोदोषवारकभाष्यम्)

नैष दोषः । यथैवात्राप्रातिपदिकत्वात्सुबुत्पत्तिर्न भवति एवं लुगपि न भविष्यति । तत्र यैवासावन्तवर्तिनी विभक्तिस्तस्या एव श्रवणं भविष्यति ॥

(इतरस्य दोषसाधकभाष्यम्)

नैवं शक्यम् । स्वरे दोषः स्यात्—बहुपटव इत्येवं स्वरः स्यात् । बहुपटव इति चेष्यते । पठिष्यति ह्याचार्यः—*चितः सप्रकृतेर्बह्वकजर्थम् * इति । तस्यां पुनर्लुप्तायां यान्या विभक्तिरुत्पद्यते तस्याः प्रकृत्यनेकदेशत्वादन्तोदात्तत्वं न भविष्यति ॥

(प्रदीपः) स्वर इति । बहुपटव इति वकाराकारस्योदात्तत्वं प्राप्नोति, टकाराकारस्य चेष्यते ॥ प्रकृत्यनेकदेशत्वादिति । नह्यसौ प्रकृतेरेकदेश इत्यर्थः ॥

(उद्योतः) टकाराकारस्येति । प्रातिपदिकत्वे सति अन्तरङ्गानपीति न्यायेन लुकि कृते डशब्दोकारस्यैव स्वरप्रवृत्तिरिति भावः ॥ नह्यसाविति । समुदायादुत्पत्तेरिति भावः ॥

(समाधानसाधकभाष्यम्)

एवं तर्ह्याचार्यप्रवृत्तिर्ज्ञापयति—भवति प्रकृतिप्रत्ययसमुदायस्य प्रातिपदिकसंज्ञा—इति । यदयम् 'अप्रत्यय' इति प्रतिषेधं शास्ति । स च तदन्तप्रतिषेधः ॥

(प्रदीपः) अप्रत्यय इति प्रतिषेधं शास्तीत्युक्ते कश्चन ब्रूयाद्बहुपटव इत्यत्राप्रत्यय इति निषेधः प्राप्नोतीत्यत आह—स च तदन्तप्रतिषेध इति ॥ प्रत्ययग्रहणे यस्मात्स विहित इति तदन्तविधिः । संज्ञाविधौ च प्रत्ययग्रहणे तदन्तविधिर्निवारितः । अप्रत्यय इत्ययं तु प्रतिषेधविधिः । पटुशब्दाचात्र जसुत्पन्नो न बहुपटुशब्दादिति बहुपटव इत्येतदप्रत्ययान्तमेव ॥ अथ वा अप्रत्यय इति बहुव्रीह्याश्रयणात् प्रत्ययादेरपि बहुपटव इत्यस्य निषेधः प्राप्नोतीत्याह—स चेति । अप्रत्यय इति तत्पुरुष आश्रीयते तस्य स्वपदार्थप्रधानत्वेनान्तरङ्गत्वादिति भावः ॥

(उद्योतः) अप्रत्यय इति निषेधः प्राप्नोतीति । जसमाश्रित्येति भावः ॥ प्रतिषेधेति । पर्युदासेपि प्रत्ययस्य संज्ञित्वाभावात्र दोष इति भावः ॥ बहुव्रीहीति । न विद्यते प्रत्ययो यस्मिन्नित्यर्थः ॥

(आक्षेपभाष्यम्)

स तर्हि ज्ञापकार्थः प्रत्ययप्रतिषेधो वक्तव्यः ॥

(प्रतिवन्दीभाष्यम्)

ननु चायं प्राप्त्यर्थोपि वक्तव्यः ॥

(प्रदीपः) प्राप्त्यर्थ इति । प्रतिषेधप्राप्त्यर्थ इत्यर्थः ॥

(प्रतिवन्दीनिरासभाष्यम्)

नार्थः प्राप्त्यर्थेन । कृत्तद्धितग्रहणं नियमार्थं भविष्यति—कृत्तद्धितान्तस्यैव प्रत्ययान्तस्य प्रातिपदिकसंज्ञा भविष्यति, नान्यस्य प्रत्ययान्तस्येति ॥

(आक्षेपभाष्यम्)

स एषोनन्यार्थः प्रत्ययप्रतिषेधो वक्तव्यः । प्रकृतिप्रत्ययसमुदायस्य वा प्रातिपदिकसंज्ञा वक्तव्या ॥

(प्रदीपः) स एषोनन्यार्थ इति । ज्ञापनार्थ एवेत्यर्थः ॥

(समाधानभाष्यम्)

उभयं न वक्तव्यम् । तुल्यजातीयस्य नियमः ॥

कश्च तुल्यजातीयः ? ॥

यथाजातीयकानां समासः ॥

कथं जातीयकानां समासः ? ॥

सुबन्तानाम् ॥

(प्रदीपः) सुबन्तानामिति । एतच्चोपलक्षणं भेदसंसर्गद्वारकार्थवत्त्वयुक्तानाम् । यस्मात्सुबन्तासुबन्तानामपि समासो दृश्यते अश्वक्रीतीत्यादौ, गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पत्तेरिति वचनात् ॥

(उद्योतः) भेदसंसर्गेति । वाक्ये पदार्थयोर्विभागेनापि प्रयोगे सतीतरसंसर्गाकाङ्क्षा भेदसंसर्गः । स द्वारभूतो यस्य विशिष्टार्थवत्त्वस्य तद्युक्तानामित्यर्थः । समासेपि वाक्यीयेनैव तेन विशिष्टार्थवत्त्वम् । नहि प्रकृतिप्रत्यययोर्विभागः परश्चेति वचनादिति भावः । एवं च समुदायघटका भागाः स्वातन्त्र्येणापि प्रयोगार्हा अर्थवन्तो गृह्यन्त इति तात्पर्यम् ॥ उपलक्षणत्वेन व्याख्याने बीजमाह—यस्मादिति ॥ अश्वक्रीतीति । सुबन्तेन समासे स्वन्तरङ्गत्वाट्टापि ङीपेव न स्यादित्यर्थः ॥

(समाधानबाधकभाष्यम्)

सुप्तिङ्समुदायस्य तर्हि प्रातिपदिकसंज्ञा प्राप्नोति ॥

(प्रदीपः) देवदत्तो ग्रामं गत इत्यादेः सुबन्तसमुदायस्यैव वाक्यस्य नियमेन निवृत्तिः स्यादित्यभिप्रायेणाह—सुप्तिङ्समुदायस्येति ॥

(उद्योतः) सुबन्तानामित्यस्योपलक्षणत्वमजानानश्चोदयतीत्याह—देवदत्त इति ॥

(समाधानसाधकभाष्यम्)

सुप्तिङ्समुदायस्यापि प्रातिपदिकसंज्ञा आरभ्यते—"जहि कर्मणा बहुलमाभीक्ष्ण्ये कर्तारं चा-

भिदधाति" इति । तन्नियमार्थं भविष्यति—एतस्यैव सुप्तिङ्समुदायस्य प्रातिपदिकसंज्ञा भवति, नान्यस्येति ।

(प्रदीपः) जहि कर्मणेति । ननु समाससंज्ञेयं समासान्तोदात्तार्था । नैष दोषः समासत्वादेव प्रातिपदिकत्वमिति तत्तुल्यजातीयताप्रतिपादनार्थमेतदुपन्यस्तम् ॥

(उद्द्योतः) ननु सुप्तिङ्समुदायस्य प्रातिपदिकसंज्ञेत्ययुक्तं, तेनान्तोदात्तस्वरस्यापि सिद्ध्यर्थं समाससंज्ञाया एव विधानादिति शङ्कते—नन्विति ॥ समासत्वादेवेति । समासमूलकार्थवत्त्वादेव प्रातिपदिकत्वमिति सुप्तिङ्समुदायस्यापि समासतुल्यजातीयताप्रतिपादनाय जहिकर्मणेत्येतदुपन्यस्तमित्यर्थः ॥ एवं च भाष्ये प्रातिपदिकसंज्ञारभ्यत इत्यस्य तन्मूलभूता समाससंज्ञारभ्यत इत्यर्थ इति तात्पर्यम् ॥

(समाधानबाधकभाष्यम्)

तिङ्समुदायस्य तर्हि प्रातिपदिकसंज्ञा प्राप्नोति ॥

(प्रदीपः) तिङ्समुदायस्येति । पश्य धावतीत्यादि । ततश्च प्रातिपदिकान्तोदात्तत्वप्रसङ्गः ॥

(उद्द्योतः) तिङन्तस्यासत्त्ववाचित्वेन संख्याकारकाद्यभावाद् विभक्त्यनुत्पत्तेः प्रातिपदिकत्वस्य फलाभावेत आह—ततश्चेति । समासस्येति सूत्रं तु परमसर्वे इत्यादौ स्वाङ्गशिटामित्यादेः प्राप्तस्य बाधाय स्यादिति तात्पर्यम् ॥

(समाधानसाधकभाष्यम्)

तिङ्समुदायस्यापि प्रातिपदिकसंज्ञाऽऽरभ्यते—"आख्यातमाख्यातेन क्रियासातत्ये" इति । तन्नियमार्थं भविष्यति—एतस्यैव तिङ्समुदायस्य प्रातिपदिकसंज्ञा भवति, नान्यस्येति ।

(प्रदीपः) आख्यातमिति । ततश्च समासेन तुल्यजातीयानां सर्वेषां वाक्यानां नियमान्निवृत्तिः सिद्धेत्यर्थः ॥

(उद्द्योतः) तुल्यजातीयानामिति । तत्त्वं च प्रयोगार्हस्वतन्त्रार्थवत्समुदायत्वेनेत्याहुः ॥ वार्तिकत्रयेणायमेवार्थ उपलक्ष्यत इति बोध्यम् ॥

(६७३ आक्षेपवार्तिकम् ॥ ७ ॥)

॥ * ॥ अर्थवत्ता नोपपद्यते केवलेनावचनात् ॥ * ॥

(भाष्यम्) अर्थवत्ता नोपपद्यते वृक्षशब्दस्य ॥ किं कारणम्? ॥ केवलेनावचनात् । न केवलेन वृक्षशब्देनार्थो गम्यते ॥ केन तर्हि? ॥ सप्रत्ययकेन ॥

(प्रदीपः) अर्थवत्तेति । अर्थवत्ता संज्ञानिमित्तत्वेनेहोपात्ता सा च वाक्यस्यैव पदस्य वा केवलस्य लोके प्रयुज्यमानस्योपपद्यते, न तु प्रकृतिभागस्य केवलस्य प्रयोगाभावाद्वर्णवद्व्यवहार्यत्वात् ॥

(६७४ आक्षेपबाधकवार्तिकम् ॥ ८ ॥)

॥ * ॥ न वा प्रत्ययेन नित्यसंबन्धात् केवलस्याप्रयोगः ॥ * ॥

न वा एष दोषः ॥ किं कारणम्? ॥ प्रत्ययेन नित्यसंबन्धात् । नित्यसंबद्धावेतावर्थौ प्रकृतिः प्रत्यय इति । प्रत्ययेन नित्यसंबन्धात् केवलस्य प्रयोगो न भविष्यति ॥

(प्रदीपः) नवेति । अन्यथासिद्धः केवलस्याप्रयोगः न केवला प्रकृतिः प्रयोक्तव्या न च केवलः प्रत्यय इति नियमात् । अर्थवत्ता त्वन्वयव्यतिरेकाभ्यामस्त्येवेति भावः ॥

(उद्द्योतः) प्रकृतिभागस्यार्थवत्त्वे किं केवलस्य प्रयोग आपाद्यते उत तत्र प्रमाणं नास्तीत्युच्यत इति विकल्पे नाद्य इत्याह—अन्यथेति ॥ द्वितीये आह—अर्थवत्ता त्विति ॥ भाष्ये—नित्यसंबन्धाविति ॥ मायेश्वरवदिति भावः ॥

(आक्षेपबाधकानुपपत्तिभाष्यम्)

अन्यद्भवान्पृष्टोन्यदाचष्टे । आम्रान् पृष्टः कोविदारानाचष्टे '*अर्थवत्ता नोपपद्यते केवलेनावचनाद् *' इति भवानस्माभिश्चोदितः केवलस्याप्रयोगे हेतुमाह ॥

(आक्षेपसाधकभाष्यम्)

एवं च किल नाम कृत्वा चोद्यते * समुदायस्यार्थे प्रयोगादवयवानामप्रसिद्धिः * इति ।

(उद्द्योतः) अवयवानामप्रसिद्धिरिति । अवयवमात्रादर्थगत्यभावेनावयवानामर्थवत्त्वे हेतोरप्रसिद्धिरित्यर्थः ॥

(६७५ समाधानवार्तिकम् ॥ ९ ॥)

॥ * ॥ सिद्धं त्वन्वयव्यतिरेकाभ्याम् ॥ * ॥

(भाष्यम्) सिद्धमेतत् । कथम्? । अन्वयाद्व्यतिरेकाच्च ॥

कोसावन्वयो व्यतिरेको वा? ।

इह वृक्ष इत्युक्ते कश्चिच्छब्दः श्रूयते वृक्षशब्दः अकारान्तः सकारश्च प्रत्ययः । अर्थोपि कश्चिद्गम्यते मूलस्कन्धफलपलाशवान् एकत्वं च । वृक्षावित्युक्ते कश्चिच्छब्दो हीयते कश्चिदुपजायते कश्चिदन्वयी—सकारो हीयते औकार उपजायते वृक्षशब्द अकारान्तोन्वयी । अर्थोपि कश्चिद्धीयते कश्चिदुपजायते कश्चिदन्वयी—एकत्वं हीयते द्वित्वमुपजायते मूलस्कन्धफलपलाशवानन्वयी । ते मन्यामहे—यः शब्दो हीयते तस्यासावर्थो यो हीयते, यः शब्द उपजायते तस्यासावर्थो योर्थ

उपजायते, यः शब्दोन्वयी तस्यासावर्थो योर्थोन्वयीति ॥

(प्रदीपः) अन्वयव्यतिरेकाभ्यामिति। अन्वयोनुगमः सति शब्देर्थावगमः। व्यतिरेकः शब्दाभावे तदर्थानवगमः ॥

(उद्द्योतः) लोके केवलप्रकृत्यादेरप्रयोगेपि ताश्रिककल्पितावन्वयव्यतिरेकौ दर्शयति—इहेत्यादिना। एवं कल्पितान्वयव्यतिरेकाभ्यां प्रकृतिप्रत्ययविभागं तयोरर्थवत्त्वं च परिकल्प्य शास्त्रेन्वाख्यानमिति भावः ॥ अत एव पूर्वप्रश्नः—कोसाविति। लोकसिद्धत्वे हि प्रश्नासङ्गतिरिति बोध्यम् ॥

(समाधानबाधकभाष्यम्)

विषम उपन्यासः। बहवो हि शब्दा एकार्था भवन्ति। तद्यथा—इन्द्रः शक्रः पुरुहूतः पुरन्दरः। कन्दुः कोष्ठः कुसूल इति। एकश्च शब्दो बह्वर्थः। तद्यथा—अक्षाः पादा माषा इति ॥

(प्रदीपः) विषम इति। यद्येकः शब्द एकस्मिन्नर्थे नियतः स्यात् तत एतद्युज्यते वक्तुम् यतस्त्वनियमः ततः प्रकृतेरेव सर्वे अर्थाः स्युः। यथा दधि मध्वग्निचिदिति। प्रत्ययस्तु क्वचिद्द्योतकः ॥ प्रत्ययस्यैव वा सर्वे अर्थाः स्युः इयानधुनेति यथा। प्रकृतिस्त्वर्थाभिधाने साहायकमात्रं कुर्यात् ॥

(उद्द्योतः) अन्वयव्यतिरेकाभ्यां प्रकृतिप्रत्यययोरर्थवत्त्वोपपादनस्यानैकान्तिकत्वमिह भाष्योक्तं वैषम्यं, तथाहि ताभ्यां नार्थसिद्धिः। अध्यागच्छतीत्यादौ निपातेषु व्यभिचारात्। तत्सत्त्वेपि तदर्थाप्रतीतेः। तद्व्यतिरेकेप्यागच्छतीत्येतन्मात्रादर्थप्रतीतेश्च। एवं च प्रकृतिप्रत्ययान्यतरस्यैव सर्वार्थतास्तु अन्यतरस्य साधुत्वमात्रार्थकत्वमस्तु। अन्यायोनेकार्थत्वमिति त्वप्रयोजकमक्षादिषु दर्शनाद् बहुपर्यायदर्शनादन्यायोनेकशब्दत्वमिति वदित्वाशयेन प्रकृतिप्रत्यययोरर्थवत्ताया अनैयत्यं दर्शयति—यद्येक इति ॥ यतस्त्विति। एवं चाक्षादिशब्दे तस्मिन्शब्दे सत्येव तदर्थाप्रतीतेरर्थान्तरप्रतीतेः पर्यायस्थले तस्मिन् शब्देऽसत्यपि तदर्थप्रतीतेश्चेदृशावन्वयव्यतिरेकावनिर्णायकाविति भावः ॥ यदि प्रकृतिरेव संख्यावाचिका तर्हि क्वापि विभक्तिर्न प्रयुज्येतेत्यत आह—प्रत्ययस्त्विति। 'इदम इश्' यस्येति लोपे इयान् ॥ अधुनेति। इदमोऽधुना प्रत्यय इति पक्षे इदम् ॥

(आशयजिज्ञासाभाष्यम्)

अतः किम् ॥

(उद्द्योतः) शक्तिुराशयं तद्वचसा ज्ञातुं पृच्छति—भाष्ये—अतः किमिति। उक्तेन बहवः शब्दा इत्यादिना ग्रन्थेन किं साधितं त्वयेति भावः ॥

(आक्षेपाशयभाष्यम्)

न साधीयोर्थवत्ता सिद्धा भवति? ॥

(प्रदीपः) अतः किं न साधीय इति। प्रकृतिः सर्वानर्थानभिदधाति। द्योतिकास्तु विभक्तय इति सिद्धैवार्थवत्ता ॥

(उद्द्योतः) इतरः स्वाशयमाह—न साधीय इति ॥ तदेवाह—न पुनरिति ॥ अन्यतरद्द्योतकमिति भावः ॥ तद्व्याचष्टे—प्रकृतिरित्यादिना। सिद्धैवेति। किं तु विपरीतं प्राप्नोतीति भावः ॥

(परिहारभाष्यम्)

न ब्रूमः—अर्थवत्ता न सिध्यतीति। वर्णिता अर्थवत्तान्वयव्यतिरेकाभ्यामेव।

(आशयान्तरभाष्यम्)

तत्र कुत एतदयं प्रकृत्यर्थोयं प्रत्ययार्थ इति। न पुनः प्रकृतिरेवोभावर्थौ ब्रूयात्। प्रत्यय एव वा? ॥

(प्रदीपः) प्रत्यय एवेति। ततश्च प्रकृतेरर्थवत्ता न सिध्यतीति तदवस्थो दोष इत्यर्थः ॥

(उद्द्योतः) तदाह—ततश्चेति। एवं च प्रकृतेरर्थवत्त्वाभावात्संज्ञा न स्यादिति भावः ॥

(समाधानसाधकभाष्यम्)

सामान्यशब्दा एते एवं स्युः। सामान्यशब्दाश्च नान्तरेण विशेषं प्रकरणं वा विशेषेष्ववतिष्ठन्ते। यतस्तु खलु नियोगतो वृक्ष इत्युक्ते स्वभावतः कस्मिंश्चिदर्थे प्रतीतिरुपजायते। अतो मन्यामहे—नेमे सामान्यशब्दा इति। न चेत्सामान्यशब्दाः, प्रकृतिः प्रकृत्यर्थे वर्तते, प्रत्ययः प्रत्ययार्थे ॥

(प्रदीपः) सामान्यशब्दा इति। प्रकृतिश्चेत्सर्वानर्थानभिदध्याद् वृक्ष इत्युक्ते सर्वा संख्या प्रतीयेत। प्रत्ययो वा सर्वस्य प्रातिपदिकस्यार्थं प्रत्याययेदित्यर्थः ॥ यतस्तु खल्विति। प्रकरणादिना विनैवेति भावः ॥

(उद्द्योतः) परिहरति—सामान्यशब्दा इति। एवं सत्येते सामान्यशब्दाः स्युस्तत्त्वं चैषां न दृश्यत इति भावः ॥ तदुपपादयति—प्रकृतिश्चेदित्यादिना। वृक्ष इत्युक्ते इत्यस्य प्रातिपदिकप्रयोगमात्रे तात्पर्यम् ॥ सामान्यशब्दाः कीदृशा इत्यत आह—भाष्ये—सामान्यशब्दाश्चेति। चो ह्यर्थे। विशेषं, विशेषबोधकपदान्तरसमभिव्याहारम्। एवं च प्रकरणादिसापेक्षतयाऽर्थप्रत्यायकत्वं सामान्यशब्दत्वमिति भावः ॥ एते तु नैवमित्याह—यतस्त्विति। त्वद्रीत्या हि प्रकृतिः स्वार्थं प्रत्ययार्थसामान्यं चाभिदधाति तत्र विना प्रकरणादिकं केवलस्वार्थस्य बोधः कथमपि न स्याद्। दृश्यते तु सः, संख्यादेश्च न सामान्यरूपेणापि बोधः। एवं प्रत्ययमात्राद् न कदापि प्रकृत्यर्थबोधः प्रकरणाद्यसत्त्वेपि च स्वार्थोपस्थितिः शास्त्रवासनावताम्। अतो नैषामुभयार्थवाचकत्वरूपं सामान्यशब्दत्वम्। ततः किमित्याह—न चेदित्यादि। प्रत्य-

यार्थे तद्द्योत्यार्थे पञ्चकं प्रातिपदिकार्थ इति मुख्यपक्षे तस्य द्योतकत्वाद् ॥

(वर्णानामर्थवत्त्वानर्थकत्वनिर्णयाधिकरणम्)

(आक्षेपभाष्यम्)

किं पुनरिमे वर्णा अर्थवन्तः, आहोस्विदनर्थकाः।

(उद्द्योतः) वर्णवारणायार्थवद्ग्रहणमित्युक्तम् । तत्र वर्णानामानर्थक्यं दृढं कर्तुं पृच्छति—भाष्ये—किं पुनरिति ॥

(६७६ समाधानवार्तिकम् ॥ १० ॥)

॥ * ॥ वर्णस्यार्थवदनर्थकत्वे उक्तम् ॥ * ॥

(भाष्यम्) **किमुक्तम् ? । *अर्थवन्तो वर्णा धातुप्रातिपदिकप्रत्ययनिपातानामेकवर्णानामर्थदर्शनाद्वर्णव्यत्यये चार्थान्तरगमनाद्वर्णानुपलब्धौ चानर्थगतेः संघातार्थवत्त्वाच्च । संघातस्यैकार्थत्वात् सुबभावो वर्णात् * । * अनर्थकास्तु प्रतिवर्णमर्थानुपलब्धेर्वर्णव्यत्ययापायोपजनविकारेष्वर्थदर्शनाद् * इति ॥**

(उद्द्योतः) उक्तमिति । हयवरट्सूत्रे इति शेषः । अनर्थगतेरिति । अर्थानवगतेरित्यर्थः । संघातार्थवत्त्वाच्च वर्णानामर्थवत्त्वमन्यथानर्थकावयवकसमुदायोऽप्यर्थवान् न स्यादित्यर्थः ॥ नन्वर्थवत्त्वे प्रत्येकं सुप् स्यादत आह—संघातस्येति ॥ एकाजुद्विर्वचनन्यायेन न प्रत्येकं विभक्तिरिति भावः ॥

(आक्षेपभाष्यम्)

तत्रेदमपरिहृतम् *संघातार्थवत्त्वाच्च * इति ॥

(समाधानभाष्यम्)

तस्य परिहारः—

(६७७ समाधानवार्तिकम् ॥ ११ ॥)

॥ * ॥ संघातार्थवत्त्वाच्चेति चेद् दृष्टो ह्यतदर्थेन गुणेन गुणिनोर्थभावः ॥ * ॥

(भाष्यम्) **संघातार्थवत्त्वाच्चेति चेद् दृश्यते हि पुनरतदर्थेन गुणेन गुणिनोर्थभावः ॥ तद्यथा—एकस्तन्तुस्त्वक्त्राणे ऽसमर्थः, तत्समुदायश्च कम्बलः समर्थः । एकश्च तण्डुलः क्षुत्प्रतिघातेऽसमर्थः, तत्समुदायश्च वर्धितकं समर्थम् । एकश्च बल्वजो बन्धने ऽसमर्थः, तत्समुदायश्च रज्जुः समर्था भवति ॥**

(प्रदीपः) **अतदर्थेनेति** । अतत्प्रयोजनेनेत्यर्थः ॥ **गुणेनेति** । अवयवेन ॥ स ह्यवयविन उपकारकत्वाद्गुणः । अवयवी तु **गुणी** । **अर्थभावः** प्रयोजनोत्पत्तिः ॥ यस्य-अस्तृणविशेषः ॥

(उद्द्योतः) अर्थशब्दस्याभिधेयपरत्वे दृष्टान्तासङ्गतिरत आह—अतत्प्रयोजनेति । यथा तत्रातत्प्रयोजनकानां समुदायस्तत्प्रयोजनस्तथेहानर्थकानां समुदायोऽर्थवानिति भावः ॥

(दृष्टान्तनिराकरणभाष्यम्)

विषम उपन्यासः । भवति हि तत्र याचयावतीचार्थमात्रा । भवति हि कंचित्प्रत्येकस्तन्तुस्त्वक्त्राणे समर्थः, एकश्च तण्डुलः क्षुत्प्रतिघाते समर्थः, एकश्च बल्वजो बन्धने समर्थः । इमे पुनर्वर्णा अत्यन्तमेवानर्थकाः ॥

(प्रदीपः) **याचयावतीचेति** । अयं समुदायः काचिदित्यस्यार्थे वर्तते ॥

(उद्द्योतः) भाष्ये याचयावतीचार्थमात्रेति । काचित्प्रयोजननिष्पत्तिरित्यर्थः ॥ तदुपपादयति—**भवति हि कंचिदिति** ॥

(दृष्टान्तान्तरभाष्यम्)

यथा तर्हि रथाङ्गानि विहृतानि प्रत्येकं व्रजिक्रियां प्रत्यसमर्थानि भवन्ति तत्समुदायश्च रथः समर्थः । एवमेषां वर्णानां समुदाया अर्थवन्तः, अवयवा अनर्थका इति ॥

(प्रदीपः) **विहृतानीति** । विक्षिप्तानीत्यर्थः ॥

(उद्द्योतः) **विक्षिप्तानीति** । विहरतिरिह पृथक्करणे वर्तत इति भावः ॥

(इति वर्णानामर्थवत्त्वनिरर्थकत्वनिर्णयः ॥)

(अथानर्थकनिपातप्रातिपदिकसंज्ञासाधनम्)

(६७८ आक्षेपवार्तिकम् ॥ १२ ॥)

॥ * ॥ निपातस्यानर्थकस्य प्रातिपदिकत्वम् ॥ * ॥

(भाष्यम्) **निपातस्यानर्थकस्य प्रातिपदिकसंज्ञा वक्तव्या । अधिपरी । अभ्युदयति । अभ्यसि । प्रलम्बते ॥**

(प्रदीपः) **अनर्थकस्येति** । निपातानां द्योतकत्वादभिधेयार्थाभावेपि द्योत्यार्थमद्भावादेषामर्थवत्त्वं तेषां सिध्यत्येव संज्ञा । यस्य तु द्योत्योऽप्यर्थो नास्ति तदर्थं वचनम् ॥

(उद्द्योतः) अनर्थकस्येति विशेषणकृत्यमाह—निपातानामिति ॥

(आक्षेपप्रयोजनजिज्ञासाभाष्यम्)

किं पुनरत्र प्रातिपदिकसंज्ञया प्रार्थ्यते ? ।

(प्रयोजनभाष्यम्)

प्रातिपदिकादिति स्वाद्युत्पत्तिः । सुबन्तं पदमिति पदसंज्ञा । "पदस्य" "पदात्" इति निघातो यथा स्यात् ॥

(प्रदीपः) **निघातो यथा स्यादिति** । अर्थवदनर्थकयोरसत्यपि सामर्थ्ये संज्ञाविधानसामर्थ्यान्निघातो भवतीत्येके ॥ समानवाक्यतानिमित्तो निघातो न सामर्थ्यनिमित्तः सा चेहास्ति आख्यातं साव्ययकारकविशेषणं वाक्यमिति परिभाषणाद्वाक्यस्येत्यपरे ॥

(उद्द्योतः) ननु पदादित्यधिकृत्य विधीयमानस्य निघातस्य पदविधित्वात्समर्थपरिभाषोपस्थितेः प्रकृते सामर्थ्याभावात्तदप्राप्तिरत आह—**अर्थवदनर्थकयोरिति** । **सामर्थ्ये** व्यपेक्षालक्षणे ॥ **सामर्थ्यादिति** । पदत्वसंपादकप्रातिपदिकसंज्ञाविधानसामर्थ्यादित्यर्थः॥ **एके इति** । अत्रारुचिस्तु **समर्थ**सूत्रे एकार्थीभावस्यैव ग्रहणेन निघातविधौ तदनुपस्थितिः । तदपवादस्य **समानवाक्ये निघाते**त्यस्य सत्वं चेति ॥ तदाह—**समानेति** ॥ **आख्यातमिति** । अत्र वाक्यलक्षणेऽर्थवत्त्वं न निविष्टमिति निखअतीत्यादेरपि वाक्यत्वं बोध्यम् । **एकतिङ्वाक्यमिति** वक्तुं युक्तम् ॥

(प्रयोजननिराकरणभाष्यम्)

नैतदस्ति प्रयोजनम् । सत्यामपि प्रातिपदिकसंज्ञायां स्वाद्युत्पत्तिर्न प्राप्नोति ॥ किं कारणम् ? । नहि प्रातिपदिकसंज्ञायामेव स्वाद्युत्पत्तिः प्रतिबद्धा ॥ किं तर्हि ? ॥ एकत्वादिष्वप्यर्थेषु स्वादयो विधीयन्ते । न चैषामेकत्वादयः सन्ति ॥

(प्रदीपः) **नहीति** । स्वादिविधिवाक्यस्य संख्याविधिवाक्येनैकवाक्यत्वात् ॥

(प्रयोजनसाधकभाष्यम्)

नैष दोषः । अविशेषेणोत्पद्यन्ते । उत्पन्नानां नियमः क्रियते ॥

अथ वा प्रकृतानर्थानपेक्ष्य नियमः ॥ के च प्रकृताः ? ॥ एकत्वादयः । एकस्मिन्नेवार्थे एकवचनं न द्वयोर्न बहुषु । द्वयोरेवार्थयोर्द्विवचनं नैकस्मिन्न बहुषु । बहुष्वेवार्थेषु बहुवचनं नैकस्मिन्न द्वयोरिति ॥

अथ वा आचार्यप्रवृत्तिर्ज्ञापयति—अनर्थकानामप्येतेषां भवत्यर्थवत्कृतम्–इति । यदयम् "अधिपरी अनर्थकौ" इत्यनर्थकयोर्गत्युपसर्गसंज्ञाबाधिकां कर्मप्रवचनीयसंज्ञां शास्ति ॥

(प्रदीपः) **अविशेषेणेति** । नानावाक्यताश्रयणात् । नियमार्थानां न प्रत्ययानामित्यनर्थकेभ्योपि ते भवन्ति ॥

अथ वेति । प्रत्ययनियमेपि दोषाभाव इत्यर्थः ॥ **अधिपरी इति** । क्रियायोगे गत्युपसर्गसंज्ञयोर्विधानादनर्थकयोः क्रियायोगाभावात्प्राप्तिरेव नास्तीति संज्ञाविधानं यथोक्तार्थस्य ज्ञापकं संपद्यते । अनर्थकत्वं च निपातस्य धातुनिपातयोः साधारणार्थतयाऽभिकथोत्यार्थाभावादच्यते, न तु सर्वात्मनार्थाभावात् ॥

(उद्द्योतः) **नानावाक्येति** । स्वौजसित्यादेर्द्व्येकयोरित्यादेश्चेत्यर्थः । **अव्ययादाप्सुप** इति लिङ्गाद्वाक्यभेदोप्यभिमत इति भावः ॥ ननु प्रत्ययनियमे दोष एवेत्यत आह—**नियमार्थानामिति** । एकत्वे एकवचनमेवेति नियमो, न त्वेकत्व एवैकवचनमिति भावः ॥ एकवाक्यतापक्षेप्यौत्सर्गिकत्वात्सर्वविभक्त्येकवचनमित्यन्यत्रोक्तम् ॥

संज्ञाविधानमिति । तयोस्तद्विधानं च केवलं गत्युपसर्गसंज्ञाबाधनार्थमेवेति भावः । अनेन च ज्ञापकेन वार्तिकं प्रत्याख्यायते, विभक्त्युत्पत्तिस्तूक्तरीत्यैवेति बोध्यम् ॥ **न त्विति** । तथा च प्रयोगो व्यर्थः स्यादिति भावः ॥ एतेन ज्ञापकं शिथिलमिति ध्वनयति । धात्वर्थानुवादकत्वरूपस्यापि योगस्य ग्रहीतुं शक्यत्वादिति बोध्यम् । ध्वनितं चेदम**धिपरी**[इ]ति सूत्रे भाष्ये ॥

(इत्यनर्थकनिपातप्रातिपदिकसंज्ञासाधनम् ॥)

(अथाप्रत्यय इत्यत्र पर्युदासप्रसज्यप्रतिषेधविचारः)

(आक्षेपभाष्यम्)

किं पुनरयं पर्युदासो यदन्यत्प्रत्ययादिति । आहोस्वित्प्रसज्यायं प्रतिषेधः—प्रत्ययो नेति ? ॥

कश्चात्र विशेषः ? ॥

(६७९ पर्युदासबाधकवार्तिकम् ॥ १३ ॥)

॥ * ॥ अप्रत्यय इति चेत् तिबेकादेशे प्रतिषेधोऽन्तवत्त्वात् ॥ * ॥

(भाष्यम्) **अप्रत्यय इति चेत्तिबेकादेशे प्रतिषेधो वक्तव्यः । काण्डे कुड्ये ॥ किं कारणम् ? ॥ अन्तवत्त्वात् ॥ तिबतिपोरेकादेशः अतिपोन्तवत्स्यात् । अस्त्यन्यत्तिप इति कृत्वा प्रातिपदिकसंज्ञा प्राप्नोति ॥**

(प्रदीपः) **तिबेकादेश इति** । तिपस्तिशब्दादारभ्य सुपः पकारेण प्रत्याहारः ॥ **अन्तवत्त्वादिति** । पूर्वस्य प्रत्ययसदृशस्य प्रातिपदिकसंज्ञाकार्यमिति पूर्वं प्रत्यन्तवद्भावः ॥

(उद्द्योतः) **अन्तवद्भाव इति** ॥ तस्य हि पर्युदासे शाब्दकार्यलाभ इति तस्यैव प्रवृत्तिर्न त्वादिवत्त्वस्येति भावः ॥ भाष्ये—**अस्त्यन्यत्तिप इति** । **अतिप्प्रातिपदिक**मिति न्यासाश्रयेणेदम् । एवं चोत्तरत्र तद्धितग्रहणं न कार्यमिति लाघवम् । पश्चनावप्रिय इत्यत्र पश्चनावेत्यस्य प्रातिपदिकत्वेपि न क्षतिः, टजन्तस्योपसर्जनत्वेन ङीपोऽप्राप्तेः, सुबपि समासे संख्याभावान्न, प्रकृते संख्याया उक्तत्वाच्च ॥ वस्तुतः प्रशस्तार्थवत्त्वाभावात्प्रातिपदिकत्वाप्राप्तिरेव ॥ एतेन टाप् स्यादित्युक्तिः परास्ता ॥ काण्डे इत्यत्र च प्रातिपदिकत्वे ह्रस्वापत्तिर्दोष इति बोध्यम् ॥ एवमोजायत इत्यत्रापि ह्रस्वापत्तिः । अत एव तिप्ग्रहणं चरितार्थम् ॥

(प्रसज्यप्रतिषेधाभ्युपगमभाष्यम्)

अस्तु तर्हि प्रसज्यप्रतिषेधः—प्रत्ययो नेति ॥

(६८० प्रसज्यप्रतिषेधबाधकवार्तिकम् ॥ १४ ॥)

॥ * ॥ न प्रत्यय इति चेदूडेकादेशे प्रतिषेध आदिवत्त्वात् ॥ * ॥

(भाष्यम्) न प्रत्यय इति चेदूडेकादेशे प्रतिषेधः प्राप्नोति । ब्रह्मबन्धूः ॥ किं कारणम् ? । आदिवत्त्वात् । प्रत्ययाप्रत्यययोरेकादेशः प्रत्ययस्यादिवत्स्यात् । तत्र प्रत्ययो नेति प्रतिषेधः प्राप्नोति ॥

किं पुनरत्र प्रातिपदिकसंज्ञया प्रार्थ्यते ? ।

प्रातिपदिकादिति स्वाद्युत्पत्तिर्यथा स्यात् ॥

(प्रदीपः) आदिवत्त्वादिति । परकार्ये प्रतिषेधे कर्तव्ये परं प्रत्येकादेशस्यादिवद्भावः ॥

(उद्द्योतः) परकार्ये इति । आदिवत्त्वस्य हि प्रतिषेधरूपं शाब्दं फलमिति भावः । न चादिवद्भावेन ऊ इत्यस्य प्रत्ययत्वेपि यतो विहितस्तदादित्वाभावात् कथं निषेधः, पूर्वान्तवद्भावेन तु तदादित्वं दुर्लभमुभयत आश्रयणे तन्निषेधादिति वाच्यम् । धान्ते समुदाये दृष्टाः शब्दा इति न्यायेनैकदेशविकृतन्यायेन च ऊङ्प्रकृतित्वारोपादक्षतेः ॥

(समाधानभाष्यम्)

नैष दोषः । आचार्यप्रवृत्तिर्ज्ञापयति—उत्पद्यन्ते ऊङन्तात्स्वादय—इति । यदयं "नोङ्धात्वोः" इति विभक्तिस्वरस्य प्रतिषेधं शास्ति ॥

अथ वा द्वे ह्यत्र प्रातिपदिकसंज्ञे अवयवस्यापि समुदायस्यापि । तत्रावयवस्य या प्रातिपदिकसंज्ञा तस्यान्तवद्भावात्स्वाद्युत्पत्तिर्भविष्यति ॥

(प्रदीपः) यदयमिति । अथ वा प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणमिति स्वादय उत्पद्यन्ते ॥

द्वे इति । तत्रान्तरङ्गत्वात्प्रत्ययोत्पत्तेः प्रागेव ब्रह्मबन्धुशब्दस्य प्रवृत्ता प्रातिपदिकसंज्ञेत्यूडेकादेशस्य पूर्वं प्रत्यन्तवद्भावादस्त्येव प्रातिपदिकत्वमिति न कश्चिद्दोषः ॥

(उद्द्योतः) भाष्ये द्वे हीति । तत्रावयवस्य सिद्धा समुदायस्य प्रार्थ्यमानेति भावः ॥

तत्रान्तरङ्गत्वादिति । प्रथमप्रवृत्तिकत्वमत्रान्तरङ्गत्वम्, उपदेशभासत्त्याः समुदायनिष्ठाया एव हि प्रत्ययान्तत्वेन निषेध इति बोध्यम् ॥ भाष्ये—अन्तवद्भावादिति । एकदेशविकृतन्यायस्याप्युपलक्षणम् ॥ न चैवं काण्डे इत्यत्र दोषः, अग्रे भाष्य एव वक्ष्यमाणत्वात् ॥

(६८१ द्वितीयाक्षेपवार्तिकम् ॥ १५ ॥)

॥*॥ सुब्लोपे च प्रत्ययलक्षणत्वात् ॥ * ॥

(भाष्यम्) सुब्लोपे च प्रत्ययलक्षणेन प्रतिषेधः प्राप्नोति ॥ राजा । तक्षा । प्रत्ययलक्षणेन प्रत्ययो नेति प्रतिषेधः प्राप्नोति ॥

(प्रदीपः) राजेति । तत्र नलोपो न स्यात् । अत्राप्यन्तरङ्गत्वात्पूर्वमेव प्रवृत्ता प्रातिपदिकसंज्ञा बहिरङ्गेण प्रतिषेधेन न शक्यते निवर्तयितुमिति परिहारोस्ति ॥

(उद्द्योतः) अत्रापीति । अत्रेदं चिन्त्यम्—नायं दोषः, कार्यकालपक्षे व्यवस्थितयोः पक्षयोरेकेन लक्ष्ये सिद्धे पक्षान्तरेण दोषशङ्काया अनौचित्यात् । ध्वनितं चेदं प्रगृह्यसंज्ञाप्रकरणे भाष्ये । अत एव पर्युदासपक्षे नायं दोषः शङ्कितोत्र भाष्ये, तस्यापयोद्देशेपि न सिध्यतीति भाष्याशयः । न च कैयटोक्तयुक्त्या सिध्यतीति वाच्यम् । लुगादिनेव प्रतिषेधेन जातनिवृत्तिरपीति भाष्याशयात् । भुक्तवन्तं प्रतीति न्यायस्यापि लुगादिशास्त्र इवात्रापि त्याग इति भावः । अत एव ज्ञापकेन परिहरति—नैष इति । यदि त्वनेन ज्ञापकेन जातनिवृत्त्यभाव एवान्वाख्यायते, लुगादिनाप्यनुत्पत्तिरेवोच्यते, अवयवलोपशास्त्रैरपि तत्तदवयवरहितस्यैव तत्तद्विषये प्रत्ययत्वादि वोध्यते, इत्युच्यते तदास्तु इत्याहुः ॥

(समाधानभाष्यम्)

नैष दोषः । आचार्यप्रवृत्तिर्ज्ञापयति—न प्रत्ययलक्षणेन प्रतिषेधो भवतीति । यदयं—"न ङिसंबुद्ध्योः" इति प्रतिषेधं शास्ति ॥

(प्रदीपः) न ङिसंबुद्ध्योरिति । ननु हे सुराजन्निति समासप्रातिपदिकसंज्ञार्थः प्रतिषेधः स्यात् । न चोत्तरस्मादेरप्रत्यय इति प्रतिषेधः मध्येपवादा इति न्यायात् । एवं तर्हि समासेप्यप्रत्यय इति वर्तते । अन्यथा सुराजाऽतिराजेत्यादौ विध्यर्थतायां संभवन्त्यां नियमार्थं समासग्रहणं न स्यात् ॥

(उद्द्योतः) ननु हे इति । समासग्रहणं विध्यर्थमिति शङ्काशयः । सुराजन् शब्दे न पूजनादिति समासान्तनिषेधः ॥ एवं तर्हीति । प्रत्याख्याने तु तद्धितनियमांशे बाध्यसामान्यचिन्ताश्रयणीयेति भावः । पर्युदासेपि ज्ञापकाश्रयणमावश्यकम् । न च स्वाश्रयाप्रत्ययान्तत्वात्सिद्धिः, अतिदिश्यमानविरुद्धस्वाश्रयकार्याभावस्यातिदेशस्वभावसिद्धत्वात् । अत एव तण्डुलानित्यादेर्न प्रातिपदिकत्वमिति न नलोपस्तत्र । इदं चासिद्धवत्सूत्रभाष्यकैयटयोः स्पष्टम् ॥ सिद्धान्ते तु समासांशे तदनुवृत्तेः फलं चिन्त्यम् ॥

(पर्युदासेपि दोषोद्धारभाष्यम्)

अथ वा पुनरस्तु पर्युदासः ॥

(दोषस्मरणभाष्यम्)

ननु चोक्तम् * 'अप्रत्यय इति चेत्तिवेकादेशे प्रतिषेधोन्तवत्त्वात्' * इति ॥

(दोषसाम्यप्रतिपादनभाष्यम्)

प्रसज्यप्रतिषेधेप्येष दोषः ॥ द्वे ह्यत्र प्रातिपदिकसंज्ञे अवयवस्यापि समुदायस्यापि । गृह्यते च

प्रातिपदिकाप्रातिपदिकयोरेकादेशः प्रातिपदिकग्रहणेन । तस्मादुभाभ्यामपि वक्तव्यं स्यात्—ह्रस्वो नपुंसके यत्तस्येति ॥ किं च नपुंसके? ॥ नपुंसकं यस्य गुणः ॥ कस्य नपुंसकं गुणः? ॥ प्रातिपदिकस्य ॥ अर्थवदधातुरप्रत्ययः प्रातिपदिकम् ॥ ४५ ॥

(प्रदीपः) **यत्तस्येति** । विभक्त्यन्तं च शक्ति[प्रधानं] संख्याप्रधानं च, न च तयोर्लिङ्गयोगः । न वान्तवद्भावेनार्थः शक्योतिदेष्टुमिति न भवति ह्रस्वः ॥ अथ वा नपुंसकत्वं प्रातिपदिकार्थस्यैव संभवतीति प्रातिपदिकग्रहणं मुख्यप्रातिपदिकपरिग्रहार्थमित्यन्तवद्भावेन यत्प्रातिपदिकं तस्य ह्रस्वाभावः ॥ अत्र च सूत्रे यदव्युत्पन्नमर्थवत्तदुदाहरणम् । व्युत्पत्तौ तु कृदन्तत्वादेव सिध्यतीति पृथगस्यारम्भोऽनर्थकः स्यात् । अव्युत्पत्तिपक्षस्य चेदमेव सूत्रं ज्ञापकमित्याहुः ॥ ४५ ॥

(उद्द्योतः) भाष्ये **गृह्यते चेति** । अन्तवत्त्वेनेति भावः ॥ **संख्याप्रधानं चेति** । काण्डे तिष्ठत इत्यादौ । तत्र च संख्याया एव स्वाश्रयसंबन्धेनान्वय इति भावः । तत्र संख्यायाः प्राधान्यं चिन्त्यं, नहि तद्विशेष्यको बोधोऽनुभवसिद्धः ॥ शक्तेः प्राधान्यं च संबन्धघटकतया बोध्यम् । प्रथमान्तस्यापि वारिणी तिष्ठत इत्यादौ क्रियाकारकभावेनैवान्वयाद्वारिकर्तृका स्थितिरित्यर्थेन संबन्धघटकशक्तेरेव प्राधान्यमिति बोध्यम् ॥ **न च तयोरिति** । तदर्थशक्तिसंख्ययोरित्यर्थः । यस्य ह्रस्वस्तस्य साक्षाद्यदा नपुंसकत्वं तदा ह्रस्वः, यस्य त्ववयवद्वारकं तस्य मा भूदित्येतदर्थं **तस्ये**त्युक्तेरिति भावः ॥ भाष्ये—**किं च नपुंसके इति** । नपुंसकलिङ्गवदर्थे किमित्यर्थः ॥ **यस्येति** । यदर्थस्येत्यर्थः ॥ **कस्येति** । किंशब्दार्थस्येत्यर्थः ॥ **प्रातिपदिकस्ये**त्यस्य सत्त्वप्रधानस्येत्यर्थः । एवं च प्रत्ययान्तपर्युदासो निषेधो वेत्युभयमपि व्यर्थम् । तत्फलं हि तत्र ह्रस्वव्यावृत्तिरेव, तस्यामन्यथा सिद्धायां तद्व्यर्थमेवेति भावः । फलान्तरं तु नास्त्येव, औत्सर्गिकैकवचनस्येष्टसिद्ध्यर्थं काचित्कत्वेन तदर्थस्य संख्याकर्माद्ययोगेन च सुब्नापत्तेः । न च प्रत्ययान्तस्य प्रातिपदिकत्वे तदवयवसुपो लुगापत्तिः, विधिवैयर्थ्यापत्तेः । तस्माद्धातुसाहचर्याद् विभक्त्यतिरिक्तशब्दघटितप्रातिपदिकावयवस्यैव तेन लुगिति न दोषः । नापि फिट्स्वरप्राप्तिः, तत्तत्स्वराणां विशेषविहितानां बाधकत्वात्, प्रकृतिप्रत्ययविभागशून्येष्वेव फिट्स्वरप्रवृत्तेश्च । नापि पचेरन्नित्यादौ नलोपप्राप्तिः । रन्तादेशस्यैव कर्तुं युक्तत्वात् । अन्यथा पर्युदासे ह्रस्ववारणेपि कार्यान्तराणामवारणाद्वस्तु पर्युदास इति भाष्यासंगतेरिति दिक् ॥ यथान्यासेप्याह—**अथ वेति** । वस्तुतो यथान्यासेपि नपुंसकलिङ्गवदर्थे विशेष्यतया वर्तमानस्येत्यर्थः । न चेदं तथेति अयं प्रयासो व्यर्थ एवेति दिक् ॥ **यत्तस्ये**त्यनेनायमेवार्थो बोध्यत इति बोध्यम् ॥ **आहुरिति** । अत्रारुचिबीजं बहुपटव इत्याद्यर्थं व्युत्पत्तिपक्षेपि सूत्रमावश्यकमिति । इदं च बहुज्विधायके कैयटे स्पष्टम् ॥ अव्युत्पत्तिपक्षज्ञापकं त्वतः कृकमिकंसेति सूत्रे कंसग्रहणमिति बोध्यम् । अस्यापि ज्ञापकत्वस्त्रूलङ्सूत्रे उपपादितम् ॥ ४५ ॥

(९८ प्रातिपदिकसंज्ञासूत्रम् ॥ १ । २ । २ आ. २ सू०)

१२० कृत्तद्धितसमासाश्च ॥ १।२ ४६॥

(आक्षेपभाष्यम्)

समासग्रहणं किमर्थम्? ॥

(६८२ समाधानवार्तिकम् ॥ १ ॥)

॥ * ॥ समासग्रहण उक्तम् ॥ * ॥

(भाष्यम्) **किमुक्तम्? । *अर्थवत्समुदायानां समासग्रहणं नियमार्थम्* इति ॥ कृत्तद्धित ॥४६॥**

(उद्द्योतः) **कृत्तद्धित ॥ ४६ ॥ अर्थवत्समुदायानामिति** ॥ लोके ऽर्थबोधकतया पृथक्प्रयुज्यमानानां यः समुदाय इत्यर्थः ॥ ४६ ॥

(९९ ह्रस्वविधिसूत्रम् ॥ १ । २ । २ आ० ३ सूत्रम्)

१२१ ह्रस्वो नपुंसके प्रातिपदिकस्य ॥ १ । २ । ४७ ॥

(प्रातिपदिकपदप्रयोजनाधिकरणम्)

(आक्षेपभाष्यम्)

प्रातिपदिकग्रहणं किमर्थम्? ॥

(प्रदीपः) **ह्रस्वो नपुंसके ॥ ४७ ॥ प्रातिपदिकग्रहणमिति** । नपुंसकलिङ्गं द्रव्यस्यैव संभवति । द्रव्यवाचित्वं तु प्रातिपदिकस्यैव, न तु सुबन्तस्य शक्तिप्रधानत्वात्, नापि तिङन्तस्य क्रियाप्रधानत्वादिति प्रश्नः ॥

(उद्द्योतः) ह्रस्वो नपुंसके ॥ ४७ ॥ **शक्तिप्रधानत्वादिति** । तिङभिहितकर्तृशक्तिबोधकत्वेन प्रथमाया अपि शक्तिप्रधानत्वमित्याशयः ॥

(६८३ समाधानवार्तिकम् ॥ १ ॥)

॥ * ॥ नपुंसकह्रस्वत्वे प्रातिपदिकग्रहणं तिङ्निवृत्त्यर्थम् ॥ * ॥

(भाष्यम्) **नपुंसकह्रस्वत्वे प्रातिपदिकग्रहणं क्रियते । तिङ्निवृत्त्यर्थम् । तिबन्तस्य ह्रस्वत्वं मा भूत् काण्डे कुड्ये । रमते ब्राह्मणकुलमिति ॥**

(प्रदीपः) **काण्डे इति ।** द्वयोरपि शक्तिशक्तिमतोरभिधानादस्ति नपुंसकार्थवृत्तित्वं सुबन्तस्यापीति भावः ॥ **रमते ब्राह्मणकुलमिति ।** यथैव साधनाश्रयां संख्यामाख्यातमुपादत्ते तथा तल्लिङ्गमपि ॥

(उद्द्योतः) **द्वयोरपीति ।** समुदायेनेति शेषः । काण्डस्य विशेषणतया प्रविष्टत्वादिति भावः ॥ **साधनेति ।** साधनगतां संख्यामाख्यातं तदर्थः क्रिया यथोपादत्ते तदुपादानेन यथा संख्यावती तथा तद्गतलिङ्गोपादानेन लिङ्गवत्यपि स्यादित्यर्थः । कारकगता संख्या आरोपेण क्रियायामेव बोध्यते तिङादिभिरिति स्पष्टं ङ्याप्प्रातिपदिकादिति सूत्रे भाष्यकैयटयोः ॥

(६८४ आक्षेपवार्त्तिकम् ॥ २ ॥)

॥ * ॥ अव्ययप्रतिषेधः ॥ * ॥

(भाष्यम्) अव्ययानां प्रतिषेधो वक्तव्यः । इह मा भूत्—दोषा ब्राह्मणकुलं दिवा ब्राह्मणकुलमिति ॥

(प्रदीपः) **अव्ययप्रतिषेध इति ।** यथोपवर्णितन्यायेनाव्ययस्यापि लिङ्गयोगात्प्राप्तिः ॥ **दोषा ब्राह्मणकुलमिति ।** दोषासहचरितत्वाद्ब्राह्मणकुलमेव दोषाशब्देनोच्यते इति ह्रस्वप्रसङ्गः ॥

(उद्द्योतः) अलिङ्गासंख्यस्याव्ययत्वादाह—**यथेति ।** तिङन्तविषयोपवर्णितेत्यर्थः । यथा तत्र साधनत्वसंबन्धेन तद्धर्मग्रहणं तथाऽत्र सामानाधिकरण्यात्स्यादिति भावः ॥ वैयधिकरण्येन दोषाशब्दे नपुंसकत्वाभिव्यक्त्यभावादाह—**दोषासहेति ।** दोषाशब्दो लाक्षणिक इत्यभिमानः ॥

(तृतीयाक्षेपभाष्यम्)

स तर्हि वक्तव्यः ॥

(आक्षेपप्रयोजननिराकरणभाष्यम्)

न वक्तव्यः । नात्राव्ययं नपुंसके वर्तते ॥ किं तर्हि ? ॥ अधिकरणमत्राव्ययं नपुंसकस्य ॥

(प्रदीपः) **नात्राव्ययमिति ।** दोषाशब्दो रात्रावित्यत्रार्थे वर्तते दिवाशब्दोऽप्यहनीत्यत्रेति ब्राह्मणकुलसाधनानां क्रियाणामधिकरणं कालो भवन्ब्राह्मणकुलस्याधिकरणं भवति—दोषा दृश्यते चरत्यधीते वेति । आधेयव्यवधानेनाधिकरणस्य क्रियाधारणात् ॥

(उद्द्योतः) **इत्यत्रार्थे इति ।** शब्दशक्तिस्वभावादिति भावः ॥ ननु कारकं क्रियाया न द्रव्यस्येति कथं नपुंसकस्याधिकरणमित्युक्तिरत आह । **ब्राह्मणकुलसाधनानामिति ॥** तत्रोपपत्तिमाह—**आधेयेति ॥**

(प्रयोजनान्तरभाष्यम्)

इह तर्हि प्राप्नोति काण्डीभूतं वृषलकुलं कुड्यीभूतं वृषलकुलमिति ।

(प्रदीपः) **काण्डीभूतमिति ।** प्रकृतिविकारयोरभेदविवक्षायां च्विप्रत्ययः । द्वयोरप्यत्र तयोर्नपुंसकत्वाद्ध्रस्वप्रसङ्गः ॥ कृते ह्रस्वत्वे **च्वौ चेति** दीर्घो भविष्यतीति चेत् । ह्रस्वस्य बहिरङ्गत्वाद्दीर्घे कर्तव्येऽसिद्धत्वाद्दीर्घाप्रसङ्गः ॥ एवं रमते इत्यत्रापि ह्रस्वे सति टेरेत्वस्याप्रसङ्गः ॥

(उद्द्योतः) **बहिरङ्गत्वादिति ।** अर्थधर्मनपुंसकत्वाश्रयत्वादित्यर्थः । एवं च पूर्वं दीर्घे ततो ह्रस्वे लक्ष्ये लक्षणस्येतिन्यायेन पुनर्दीर्घाप्रसङ्ग इति भावः ॥ वस्तुतः समत्वेपि परत्वात् **च्वाविति** दीर्घे ततो ह्रस्वे लक्ष्ये लक्षणस्येति न्यायेन पुनरप्रवृत्तिरिति बोध्यम् ॥

(६८५ समाधानवार्त्तिकम् ॥ ३ ॥)

॥ * ॥ न वा लिङ्गाभावात् ॥ * ॥

(भाष्यम्) न वा वक्तव्यम् ॥ किं कारणम् ? ॥ लिङ्गाभावात् । अलिङ्गमव्ययम् ॥

(प्रदीपः) **न वेति ।** असत्त्ववाचित्वादव्ययस्य न तेन लिङ्गं प्रतिपाद्यत इत्यर्थः ॥

(उद्द्योतः) **असत्त्वेति ।** कचिल्लिङ्गवता सामानाधिकरण्येपि तस्य लिङ्गवत्तया स्वार्थबोधकत्वाभाव इति भावः ॥

(आक्षेपभाष्यम्)

किं पुनरयमव्ययस्यैव परिहारः आहोस्वित्तिवन्तस्यापि परिहारः ? ॥

(समाधानभाष्यम्)

तिवन्तस्यापीत्याह ॥ कथम् ? । अव्ययं हि किंचिद्विभक्त्यर्थप्रधानं किंचित्क्रियाप्रधानम्—उच्चैर्नीचैरिति विभक्त्यर्थप्रधानम्, हिरुक् पृथगिति क्रियाप्रधानम् । तिवन्तं चापि किंचिद्विभक्त्यर्थप्रधानं किंचित्क्रियाप्रधानम्—काण्डे कुड्ये इति विभक्त्यर्थप्रधानं, रमते ब्राह्मणकुलमिति क्रियाप्रधानम् । न चैतयोरर्थयोर्लिङ्गसंख्याभ्यां योगोस्ति ॥ अवश्यं चैतदेवं विज्ञेयम् । क्रियमाणेपि हि प्रातिपदिकग्रहणे इह प्रसज्येत—काण्डे कुड्ये । द्वे ह्यत्र प्रातिपदिकसंज्ञे । अवयवस्यापि समुदायस्यापि । गृह्यते च प्रातिपदिकाप्रातिपदिकयोरेकादेशः प्रातिपदिकग्रहणेन । तस्मादुभाभ्यामिति वक्तव्यं स्याद्—ह्रस्वो नपुंसके यत्तस्येति ॥ किं च नपुंसके ? ॥ नपुंसकं यस्य गुणः ॥ कस्य च नपुंसकं गुणः ? ॥ प्रातिपदिकस्य ॥

(प्रदीपः) **न चैतयोरिति ।** आख्यातस्य शक्त्याश्रयद्रव्यसंख्याप्रतिपादने सामर्थ्यं न तु तल्लिङ्गप्रतिपादने विचित्रत्वाद्भावशक्तीनाम् । काण्डे तिष्ठत इत्यत्रापि संख्यायाः प्राधान्यान्नपुंसकत्वायोगः ॥ **अवश्यमिति ।** यथावयवधर्मेण समुदायो व्यपदिश्यते इत्यर्थः ॥ **यत्तस्येति ।** साक्षात् तस्यैव

यदा नपुंसकत्वं तदा ह्रस्वः । यस्य त्ववयवद्वारकं तस्य मा भूत् । अथ वा तस्यैवानुपजातव्यतिरेकस्येत्यर्थः । विभक्त्यन्तं चोपजातव्यतिरेकमिति ह्रस्वाभावः । सूत्रकारेण तु प्रातिपदिकग्रहणं मुख्यप्रातिपदिकपरिग्रहार्थं कृतं प्रातिपदिकस्यैव नपुंसके वृत्तिसम्भवात् । तेनान्तवद्भावादतिदिष्टप्रातिपदिकत्वस्य ह्रस्वाभावः ॥

(उद्योतः) किञ्चिदित्यादि । नैतावता द्विविधमेवाव्ययमिति भ्रमितव्यम् । उभयातिरिक्तस्यापि चाव्ययस्य सत्त्वात् ॥ हिरुगादेः क्रियाप्रधानत्वं क्रियामात्रविशेषणत्वेन । काण्डीभूतमित्यत्राप्येतदेव । स्वभावाच्च तादृशस्य लिङ्गाद्ययोगः ॥ न चैतयोरिति । प्रायेणेति शेषः । तत्राव्ययार्थस्य काण्डे इत्यादेश्चोभयायोगः, रमते इत्यादेर्लिङ्गायोग इति बोध्यम् । अन्यथा हतशायिकाः शय्यन्त इत्यादौ पचतिरूपमित्यादौ च ताभ्यां योगेन भाष्यासंगतिः स्यात् ॥ भावशक्तीति । पदार्थशक्तीत्यर्थः ॥ विचित्रत्वादित्यनेनेदं सूचयति पचतिकल्पमित्यादौ भवत्येव, पचतकीत्यादौ च नेति ॥ काण्डे तिष्ठत इति । प्रथमायाः प्रातिपदिकार्थे विधानाद्विभक्त्यर्थाप्रधानत्वेनास्त्येव लिङ्गयोग इति स्यादेव ह्रस्वत्वमित्यभिमानः ॥ समाधत्ते—संख्याया इति । विभक्त्या संख्याया लिङ्गवत्त्वेनाप्रतिपादनं भावशक्तेर्वैचित्र्यादिति भावः । अत्र संख्याया इति शक्तेरुपलक्षणं संख्यायाः प्राधान्यासंभवात् ॥ प्रथमास्थलेपि यथा शक्तिरस्ति तथोक्तम् ॥ भाष्ये—ऽवश्यं चैतदेवमिति । एतत् तिङन्तमलिङ्गमित्यवश्यं स्वीकार्यमित्यर्थः ॥ समुदायस्याप्युक्तं प्रातिपदिकत्वमुपपादयति—गृह्यते च प्रातिपदिकेत्यादिना ॥ अवयवधर्मेणेति । अवयवभूतप्रकृत्यर्थधर्मेणेत्यर्थः ॥ समुदायः । प्रत्ययान्तः । यद्यवयवधर्मेण समुदायस्य व्यपदेशस्तदा प्रातिपदिकग्रहणे क्रियमाणेप्येतदवश्यं वाच्यमिति भाष्यार्थ इति भावः ॥ भाष्ये—उभाभ्यामपि वक्तव्यमिति । एवमर्थकतया सूत्रं व्याख्येयमित्यर्थः ॥ अवयवद्वारा समुदायस्यापि नपुंसके वृत्तिसम्भवात्कथमनेन परिहारोत आह—साक्षादिति ॥ तस्यैव । तज्जन्यबोधविशेष्यस्य ॥ अनुपजातव्यतिरेकस्य । अनुपजातसंबन्धस्य, अनुपजातेतराकाङ्क्षस्येति यावत् । अनेन सत्त्वप्रधानत्वमुपलक्षितम् ॥ सूत्रकारेण त्विति । अवयवद्वारकमपि नपुंसकवृत्तित्वं गृह्यत इति तदाशयः । अत्र यद्वक्तव्यं तदुक्तम् । यदर्थस्य शास्त्रे नपुंसकं गुणः प्रसिद्धस्तस्य नपुंसके वर्तमानस्य ह्रस्व इति भाष्यार्थः ॥

(अनिष्टनिवारणाधिकरणम्)

(६८६ आक्षेपवार्तिकम् ॥ ४ ॥)

॥*॥ यणेकादेशदीर्घैत्त्वेषु प्रतिषेधः ॥ * ॥

(भाष्यम्) यणेकादेशदीर्घैत्त्वेषु प्रतिषेधो वक्तव्यः । युगवरत्राय । युगवरत्रार्थम् । युगवरत्रेभ्यः ॥

(प्रदीपः) युगवरत्रायेति । दीर्घे कृते पुनर्ह्रस्वः पुनर्दीर्घ इति चक्रकप्रसङ्गः ॥ ४७ ॥

(उद्योतः) [चक्रकप्रसङ्ग इति । लक्ष्ये लक्षणस्येति न्यायमनालोच्येदम् ॥]

(६८७ समाधानवार्तिकम् ॥ ५ ॥)

॥ * ॥ यणेकादेशदीर्घैत्त्वेषु बहिरङ्गलक्षणत्वात्सिद्धम् ॥ * ॥

(भाष्यम्) बहिरङ्गा एते विधयः । अन्तरङ्गं ह्रस्वत्वम् । असिद्धं बहिरङ्गमन्तरङ्गे ॥

(उद्योतः) भाष्ये—अन्तरङ्गं ह्रस्वत्वमिति । एवं च ह्रस्वत्वे कृते दीर्घप्रवृत्तेर्लक्ष्ये लक्षणस्येति न्यायेन पुनरप्रवृत्तिरित्यर्थः ॥ ४७ ॥

(६८८ प्रागुक्ताक्षेपसमाधानानुकर्षवार्तिकम् ॥ ६ ॥)

॥ * ॥ उपसर्जनह्रस्वत्वे च ॥ * ॥

(भाष्यम्) किम् ? । *यणेकादेशदीर्घैत्त्वेषु प्रतिषेधो वक्तव्यः* ॥ अतिखट्वाय । अतिखट्वार्थम् । अतिखट्वेभ्यः ॥ *बहिरङ्गलक्षणत्वात्सिद्धम्* इत्येव । बहिरङ्गा एते विधयः । अन्तरङ्गं ह्रस्वत्वम् । असिद्धं बहिरङ्गमन्तरङ्गे ॥ ह्रस्वो नपुंसके ॥ ४७ ॥

(१०० ह्रस्वविधिसूत्रम् ॥ १ । २ । २ आ० ४ सू०)

१२२ गोस्त्रियोरुपसर्जनस्य ॥ १।२।४८॥

(न्यायान्तरनिराकरणाधिकरणम्)

(६८९ आक्षेपवार्तिकम् ॥ २ ॥)

॥ * ॥ गोटाङ्ग्रहणं कृन्निवृत्त्यर्थम् ॥ * ॥

(भाष्यम्) गोटाङ्ग्रहणं कर्तव्यम् ॥ किमिदं टाङिति? ॥ प्रत्याहारग्रहणम् ॥ क संनिविष्टानां प्रत्याहारः ? ॥ टापः प्रभृत्या ष्यङो ङकारात् ॥ किं प्रयोजनम् ? । कृन्निवृत्त्यर्थम् । कृत्स्त्रिया धातुकि-

याश्च ह्रस्वत्वं मा भूदिति । अतितन्त्रीरतिश्रीरतिलक्ष्मीरिति ॥

(प्रदीपः) गोस्त्रियोरुपसर्जनस्य ॥४८॥ कृन्निवृत्त्यर्थमिति । धातुस्त्रिया अपि कृदन्तत्वाद्भेदेनानिर्देशः । भाष्यकारस्तु तदेव विभज्य व्याचष्टे—कृत्स्त्रिया धातुस्त्रियाश्चेति ॥

(उद्द्योतः) गोस्त्रियोरु० ॥ ४८ ॥ भाष्यवार्तिकयोर्विभज्य कथनाकथने हेतुमाह—धात्विति ॥

(तटस्थाक्षेपभाष्यम्)

तत्तर्हि वक्तव्यम् ॥

(सिद्धान्तिसमाधानभाष्यम्)

न वक्तव्यम् । स्त्रीग्रहणं स्वरयिष्यते । तत्र स्वरितेनाधिकारगतिर्भवति । "स्त्रियाम्" इत्येवं प्रकृत्य ये विहितास्तेषां ग्रहणं विज्ञास्यते स्वरितेनाधिकारगतिर्भवतीति न दोषो भवति ॥

(प्रदीपः) स्वरितेनेति । स्वरितेनाधिकार इति योगोनेकधा व्याख्यातः । ततश्च 'यत्र स्वरितत्वं प्रतिज्ञायते तत्र तदधिकारो गृह्यते' इत्ययमपि तस्यार्थः ॥ स्त्रियां क्तिन्नित्येतत्प्रकरणविहितानां तु ह्रस्वभावित्वाभावादग्रहणम् ॥

(उद्द्योतः) ननु स्वरितत्वे उत्तरत्रानुवृत्तिरेव स्यान्न तु तदधिकारस्तलाभोत आह—स्वरितेनेति ॥ ह्रस्वभावित्वाभावादिति । न चातिमतेरित्यादौ सम्भवः, गुणस्य बहिरङ्गत्वेनासिद्धत्वात् । किं च तद्ग्रहणेऽन्तरङ्गत्वात्पूर्वमेव ह्रस्वे ततो गुणे लक्ष्ये लक्षणस्येति न्यायेन पुनस्तत्प्रवृत्तौ फलाभाव इति भावः ॥

(आक्षेपभाष्यम्)

यद्येवं प्रत्ययग्रहणमिदं भवति । तत्र 'प्रत्ययग्रहणे यस्मात्स तदादेर्ग्रहणं भवति' इतीह न प्राप्नोति—अतिराजकुमारिः, अतिसेनानीकुमारिरिति ॥

(समाधानभाष्यम्)

"अस्त्रीप्रत्ययेन" इत्येवं तत् ॥

(प्रदीपः) अस्त्रीप्रत्ययेनेत्येवं तदिति । ननु ष्यङः सम्प्रसारणमित्यत्रातिकारीषगन्ध्यपुत्र इत्यत्र सम्प्रसारणाभावार्थमनुपसर्जनस्त्रीप्रत्ययविषयस्तदादिनियमप्रतिषेधः प्रदर्शित इत्युपसर्जनत्वादिह नियमेन भाव्यम् । नैष दोषः । क्वचिदुपसर्जनेपि तदादिनियमो न भविष्यति । हल्ङ्याब्भ्य इत्यत्र दीर्घग्रहणात् । अन्यथा निष्कौशाम्बिरतिखट्व इत्यादावुपसर्जनत्वादङ्याबन्तत्वात्सुलोपो न भविष्यतीति किं दीर्घग्रहणेन ॥ कथं तर्ह्यनुपसर्जनादित्यत्र कौम्भकारेयो न सिद्ध्यतीत्युक्तं यावता कारशब्दादपि ङीपि कृते तदादिनियमाभावात् कुम्भकारीशब्दात् ढक् भविष्यति ॥ नैष दोषः । तदादिनियमाभावे कारीशब्दादपि कदाचित् ढक् स्यात् ॥

(उद्द्योतः) भाष्ये—अस्त्रीप्रत्ययेनेति । एवं च स्त्रीप्रत्यये तदादिनियमाभावाद् ह्रस्वसिद्धिरित्यर्थः ॥ अतिकारीषेति । कारीषगन्ध्यामतिक्रान्तस्य पुत्र इति विग्रहः ॥ अनुपसर्जनेति । एवं च ष्यङ (न्तस्य) अतिक्रान्तार्थे प्रत्युपसर्जनत्वात्तदादिनियमेन पुत्रोत्तरपदकतत्पुरुषे ष्यङन्तस्यापूर्वपदत्वान्न संप्रसारणमित्यर्थः ॥ उपसर्जनत्वादिहेति । वस्तुतश्चिन्त्यमेतत् । प्रत्यासत्त्या यस्य समुदायस्य स्त्रीप्रत्ययान्तत्वं प्रार्थ्यते तदर्थं प्रत्यनुपसर्जनत्वेन तदादिनियमाप्रवृत्तौ दोषाभावात् ॥ किं दीर्घेति । हल्ङ्यादिसूत्रे हल्ङ्याब्भ्य इत्यस्य परविशेषणत्वेनावयवङ्यन्तात्परत्वेन ङ्यन्तान्तात्परत्वेन च निष्कौशाम्बिरित्यादौ सोर्लोपवारणार्थत्वाद्दीर्घग्रहणस्येदमपि चिन्त्यम् । विहितविशेषणे तु या सेत्यादावव्याप्तिः कर्त्रेत्यादावव्याप्तिश्च । अत्वादिविधौ विषयसप्तमी तु तस्मिन्निति शास्त्रबाधापत्त्या गमकाभावेन चायुक्तेति दिक् ॥ कारीशब्दादपीति । तथा च कुम्भशब्दे आदिवृद्धिर्न स्यादपीति भावः ॥

(अनिष्टह्रस्वापत्तिवारणाधिकरणम्)

(६९० आक्षेपवार्तिकम् ॥ ३ ॥)

॥*॥ ईयसो बहुव्रीहौ पुंवद्वचनम् ॥ * ॥

(भाष्यम्) ईयसो बहुव्रीहौ पुंवद्भावो वक्तव्यः । बह्व्यः श्रेयस्योऽस्य बहुश्रेयसी विद्यमानश्रेयसी ॥

(प्रदीपः) पुंवद्वचनमिति । यथा पुंविषये ईकारः श्रूयते, न तु ह्रस्वत्वं प्रतिपद्यते तथेयसोपि पर इत्यर्थः ॥

(उद्द्योतः) ननु पुंवदतिदेशे स्त्रीप्रत्ययस्यापि निवृत्तिः स्यादत आह—यथेति । ईयसः परस्य स्त्रीप्रत्ययस्य बहुव्रीहौ विद्यमानस्य पुंवत् पुंसि यथा यवीरित्यादावीकारस्य श्रवणं तथा तत्र स्त्रीप्रत्ययभूतस्यापीत्येवं वचनव्यक्तयेति भावः ॥ अत एवात्रैवेदं कृतम्, अन्यथा पुंवद्भावप्रकरण एव वदेत् ॥ ईयसश्चेतिप्रतिषेधान्न कप् । नपुंसकह्रस्वत्वं तु भवत्येवात्र पाठात् । न च नेत्येव सिद्धे पुंवद्वचनं व्यर्थं, वार्तिकाक्षरेषु लाघवगौरवविचाराभावादित्याहुः ॥ अन्ये तु तस्याप्यभावं मन्यन्ते अत एवोत्तरवार्तिके नपुंसकह्रस्वत्वस्यापि निषेध इति भ्रमव्यावृत्तये गोसमासनिवृत्त्यर्थमित्युक्तम् । अत एव च विग्रहे स इत्यादि न प्रयुक्तमित्याहुः । तत्र समासपदं स्त्र्यन्तसमासपरम् ॥

(६९१ आक्षेपवार्तिकम् ॥ ४ ॥)

॥ * ॥ पूर्वपदस्य च प्रतिषेधो गोसमासनिवृत्त्यर्थम् ॥ * ॥

(भाष्यम्) पूर्वपदस्य च प्रतिषेधो वक्तव्यः ॥ किं प्रयोजनम् ? ॥ गोसमासनिवृत्त्यर्थम् । गोनिवृत्त्यर्थं समासनिवृत्त्यर्थं च ॥ गोनिवृत्त्यर्थं तावत्—गोकुलं गोक्षीरं गोपालक इति ॥ समासनिवृत्त्यर्थम्—राजकुमारीपुत्रः सेनानीकुमारीपुत्र इति ।

(प्रदीपः) गोकुलमिति । प्रथमानिर्दिष्टमिति गोशब्दस्योपसर्जनत्वम् ॥ राजकुमारीपुत्र इति । राजकुमारीशब्दः समासप्रातिपदिकम् ॥

(उद्द्योतः) प्रथमेति । षष्ठीति प्रथमानिर्दिष्टत्वादित्यर्थः ॥ शास्त्रीयमिहोपसर्जनं न तु केवललौकिकमेवेति भावः । प्रत्ययलक्षणेनाप्रत्यय इति निषेधाप्रवृत्तेर्गोशब्दस्य प्रातिपदिकत्वमस्त्येव ॥ राजकुमारीशब्द इति । नन्वस्यानुपसर्जनत्वात्तदादिनियमाभावेन प्रत्ययान्तत्वात् कथं प्रातिपदिकत्वम् । न च समासत्वात्, समासग्रहणस्य नियमार्थत्वभङ्गापत्तेस्तत्राप्यप्रत्यय इत्यनुवृत्तेरुक्तत्वेन तेनापि दुर्लभत्वाच्चेति चेन्न । स्त्रीप्रत्ययविशेषस्य सामान्यस्य वा ग्रहणाभावेन तदप्रवृत्तेः ॥

(प्रत्याक्षेपभाष्यम्)

किमुच्यते समासनिवृत्त्यर्थमिति न पुनरसमासोपि किंचित्पूर्वपदं यदर्थः प्रतिषेधः स्यात्? ॥

(उद्द्योतः) भाष्ये—किमुच्यत इति । गोस्त्रीनिवृत्त्यर्थमित्येव वक्तुं युक्तमिति भावः ॥ न पुनरिति । असमासोपि किंचित्पूर्वपदं स्त्र्यन्तं नेति काका प्रश्नः ॥

(प्रत्याक्षेपनिराकरणभाष्यम्)

स्त्र्यन्तस्य प्रातिपदिकस्योपसर्जनस्य ह्रस्वो भवतीत्युच्यते । न चान्तरेण समासं स्त्र्यन्तं प्रातिपदिकमुपसर्जनमस्ति ॥

(प्रदीपः) इह तु कुमारीपुत्र इति कुमारीशब्दस्य प्रत्ययान्तत्वात् प्रातिपदिकत्वाभावः ॥

(उद्द्योतः) भाष्ये न चान्तरेणेति ॥ तदाशयमाह—इह त्विति । एतच्चाप्रत्यय इति सूत्रन्यासे, अतिङिति न्यासे तु कुमारीत्यस्यापि तत्त्वमस्त्येवेति तत्रापि दोषः ॥

(निराकरणहेतुबाधकभाष्यम्)

ननु चेदमस्ति खट्वापादो मालापाद इति । एकादेशे कृतेन्तादिवद्भावात्प्राप्नोति ॥

(निराकरणसाधकभाष्यम्)

उभयत आश्रयणे नान्तादिवत् ॥

(प्रदीपः) उभयत इति । प्रातिपदिकं स्त्रीप्रत्ययश्चेहाश्रीयते । तत्र यदि प्रातिपदिकस्यान्तवत् तदा स्त्रीप्रत्ययः परो नास्ति । अथ स्त्रीप्रत्ययस्यादिवत् तदा प्रातिपदिकत्वाभावः ॥

(उद्द्योतः) भाष्ये उभयत इति । ऐणेयसिद्धये स्त्रीभ्यो ढगित्यत्र प्रातिपदिकादित्यसंबन्धाद् गाङ्गेये न दोषः । प्रातिपदिकग्रहणे लिङ्गविशिष्टस्येति परिभाषामनाश्रित्येदं, तयाहि प्रातिपदिकत्वतद्व्याप्यधर्माणां स्त्रीप्रत्ययविशिष्टे बोधनमिति बहुव्रीहेरूधस इत्यत्र भाष्ये स्पष्टम् ॥ वक्ष्यमाणसमाधानेन सर्वसमाधानादेकदेश्युक्तावत्र नात्यादृतं तु भगवतेति बोध्यम् ॥

(प्रथमप्रयोजनप्रत्याख्यानभाष्यम्)

गोनिवृत्त्यर्थेन तावन्नार्थः । गोन्तस्य प्रातिपदिकस्योपसर्जनस्य ह्रस्वो भवतीत्युच्यते । न चैतद्गोन्तम् ॥

(प्रदीपः) गोन्तस्येति । उपसर्जनग्रहणेन गोस्त्रियौ विशेष्येते पश्चात् ताभ्यां प्रातिपदिकमिति तदन्तविधिः । ग्रहणवतेत्येतच्च प्रत्ययविधिविषयत्वादिह नोपतिष्ठते ॥

(उद्द्योतः) ननु चित्रगुरित्यादौ गोन्तस्य प्रातिपदिकस्योपसर्जनत्वाभावाद्ध्रस्वाप्राप्तिरत आह—उपसर्जनेति । श्रुतत्वादिति भावः ॥ गोस्त्रियाविति । गोस्त्रीप्रत्ययान्तावित्यर्थः ॥

(प्रत्याख्यानबाधकभाष्यम्)

ननु चैतदपि व्यपदेशिवद्भावेन गोन्तम् ॥

(प्रत्याख्यानसाधकभाष्यम्)

व्यपदेशिवद्भावोऽप्रातिपदिकेन ॥

(प्रदीपः) व्यपदेशिवद्भाव इति । ननु *रोण्या अण् तस्य चेत्यत्र 'तस्य चेति सर्वस्य शेष' इति व्याख्यानात् स्वंरूपमित्यस्यानुवृत्त्यनुज्ञानात् गोकुलमिति ह्रस्वः प्राप्नोत्येव नैष दोषः। स्वं रूपमिति तत्र नानुवर्तते । तथा चाद्यन्तवत्सूत्रे * येन विधिस्तदन्तत्वे * इति प्रयोजनमुक्तम् ॥ तस्य चेत्येतत् तु तत्रत्यवार्तिकस्य शेषो न तु सूत्रस्य । अगोपुत्र इत्यत्रापि न भवति । अत्र ह्यन्यत्प्रातिपदिकं गोन्तम् । अन्यत्प्रति गोशब्दस्योपसर्जनत्वम् ॥

(उद्द्योतः) ननु सूत्रस्येति । वस्तुतः सूत्रशेषत्वेपि न क्षतिः । येन विधिरसमासे निष्कादिभ्य इति सूत्रभाष्ययोरस्याः प्रत्ययविधिविषयतायाः सूत्रोपात्तान्तादिशब्दविषयतायाश्च बोधितत्वेनास्य भाष्यस्यैकदेश्युक्तित्वावश्यकत्वाद् वक्ष्यमाणसमाधानेनास्यापि परिहारः । तच्च गोशब्दांशेप्यावश्यकमिति ध्वनयन्नाह—अगोपुत्र इति । नञस्तत्पुरुषादिति समासान्तनिषेधः ॥

(द्वितीयप्रयोजनप्रत्याख्यानभाष्यम्)

समासनिवृत्त्यर्थेन चापि नार्थः । स्त्र्यन्तस्य प्रातिपदिकस्योपसर्जनस्य ह्रस्वो भवतीत्युच्यते । प्रधानमुपसर्जनमिति च संबन्धिशब्दावेतौ । तत्र संबन्धादेतद्गन्तव्यं यं प्रति यदप्रधानं तस्य चेत्सोन्तो भवतीति ॥ अवश्यं चैतदेवं विज्ञेयम् । उच्यमानेपि हि प्रतिषेध इह प्रसज्येत—पञ्च कुमार्यः प्रिया अस्य पञ्चकुमारीप्रियः, दशकुमारीप्रिय इति ॥

(प्रदीपः) पञ्चकुमारीप्रिय इति । त्रिपदे बहुव्रीहौ कृते द्वयोः पदयोर्द्विगुसमास इति पञ्चकुमारीशब्दः पूर्वपदं न भवति ॥

(उद्द्योतः) भाष्ये—प्रधानमुपसर्जनमिति । अत्र सूत्रे सम्भवसत्त्वाद् लौकिकार्थसमानाधिकरणशास्त्रीयस्यैव ग्रहणमिति भावः ॥ केवललौकिकस्य ग्रहणे तु गार्गी चासौ वृन्दारिका चेति गार्ग्यवृन्दारिकेत्यादौ वृन्दारिकाशब्दस्य गुणशब्दत्वादप्रधानत्वादु-

रपदत्वात्तदन्तस्य समासप्रातिपदिकत्वाच्च ह्रस्वप्रसङ्ग इति दिक् ॥ यं प्रतीत्यादि । यदर्थं प्रति यदर्थस्याप्रधानत्वं तद्बोधकस्य चेत्तद्बोधको गोशब्दादिरन्तो भवतीत्यर्थ इति कैयटानुसारिणः॥ परे तु प्रथमानिर्दिष्टमिति सूत्रोक्तरीत्या येन शब्देन समासविधौ यत्प्रथमानिर्दिष्टं तस्य तं प्रत्यप्रधानत्वेनोपसर्जनत्वात् प्रत्यासत्त्या तत्समासप्रातिपदिकान्त्यस्यैव ह्रस्व इति भाष्यार्थः । अत एव यं प्रति यद्वृत्ति भिन्नलिङ्गनिर्देश इत्याहुः ॥ वार्तिकेन यथा न सिध्यति तथोपपादयति—त्रिपदे इति । द्विगुसमास इति । अत एव तस्य समुदायस्य प्रातिपदिकत्वम् ॥

(६९२ आक्षेपवार्तिकम् ॥ ५ ॥)

॥ * ॥ कपि च ॥ * ॥

(भाष्यम्) कपि च प्रतिषेधो वक्तव्यः । बहुकुमारीकः । बहुवृषलीकः ॥

(प्रदीपः) कपि चेति । अन्तरङ्गत्वाद् ह्रस्वः प्राप्नोति ततः कविति भावः । कपीति च विषयसप्तमी ।

(उद्योतः) कपि कृते स्त्रीप्रत्ययान्तत्वाभावादाह—अन्तरङ्गत्वादिति ॥ कपः प्राक् प्राप्तो ह्रस्वः कपि चेति वार्तिकेन कथं निवर्त्योत आह—कपीति चेति ॥

(६९३ आक्षेपवार्तिकम् ॥ ६ ॥)

॥ * ॥ द्वन्द्वे च ॥ * ॥

(भाष्यम्) द्वन्द्वे च प्रतिषेधो वक्तव्यः । कुक्कुटमयूर्यौ ॥

(प्रदीपः) कुक्कुटमयूर्याविति । समासार्थे अवयवार्थस्याप्राधान्यादनेकमित्यस्यानुवृत्त्या प्रथमानिर्दिष्टत्वाच्च मयूरीशब्दस्योपसर्जनत्वम् ॥

(उद्योतः) द्वन्द्वस्योभयपदार्थप्रधानत्वेनानुपसर्जनत्वादाह—समासार्थ इति । उद्भूतावयवभेदसमूहः समासार्थस्तत्रावयवाप्रधानमित्यर्थः ॥ नन्वेवमपि शास्त्रीयोपसर्जनत्वाभावात्कथं प्राप्तिरत आह—प्रथमेति ॥ परे स्वत्रैकविभक्तीत्युपसर्जनत्वम्, समासापेक्षया च तत्र नियतविभक्तिकत्वं, द्वन्द्वश्च प्रथमान्तानामेव न परिनिष्ठितविभक्त्या । वाक्ये प्रत्येकमेव कर्मत्वकरणत्वाद्यवगत्या समासे च समुदाये एव तदवगत्या समाससमानार्थत्वाभावेन तस्य वाक्यत्वासम्भवात् । अत एव यदग्नये च प्रजापतये चेत्यादौ वाक्ये प्रत्येकमेव देवतात्वमग्नीषोमावित्यादौ समासे च समुदितस्यैवेति व्यवस्था सिध्यति । ध्वनितं चेदं न क्सिसंबुद्ध्योरिति सूत्रे भाष्ये इति तत्रैव निरूपयिष्याम इत्याहुः ॥

(६९४ समाधानवार्तिकम् ॥ ७ ॥)

॥ * ॥ उक्तं वा ॥ * ॥

(भाष्यम्) किमुक्तम् ? ॥ कपि तावदुक्तं—"न कपि" इति प्रतिषेधः—इति ॥

(निराकरणभाष्यम्)

नैतदस्त्युक्तम् । "केणः" इति या ह्रस्वप्राप्तिस्तस्याः प्रतिषेध इति ॥ कुत एतत् ? । 'अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा' इति ॥ अवश्यं चैतदेवं विज्ञेयम् । यो हि मन्यते या च यावती च ह्रस्वप्राप्तिस्तस्याः सर्वस्याः प्रतिषेध इति, इहापि तस्य प्रतिषेधः प्रसज्येत—प्रियं ग्रामणि ब्राह्मणकुलमस्य प्रियग्रामणिकः, प्रियसेनानिकः ॥

(उद्योतः) प्रियं ग्रामणि इति । तस्य नपुंसकत्वप्रदर्शनाय ब्राह्मणकुलमित्यस्योपन्यासः । अत्र नपुंसकह्रस्वस्यापि निषेधः स्यादित्यर्थः ॥ प्रकल्प्य चापवादविषयमिति न्यायेन पूर्वमपि ह्रस्वो न स्यादिति तात्पर्यम् ॥

(उत्तरभाष्यम्)

इदं तर्ह्युक्तम्—'कपि कृते अनन्त्यत्वाद् ह्रस्वत्वं न भविष्यति' ॥ इदमिह संप्रधार्यम्—कप् क्रियतां, ह्रस्वत्वमिति । किमत्र कर्तव्यम् ? । परत्वात् कप् ॥ अन्तरङ्गं ह्रस्वत्वम् ॥ अन्तरङ्गतरः कप् ॥

(प्रदीपः) अनन्त्यत्वादिति । समासान्त इति वचनात् कबेव समासस्यान्त इति स्त्रीप्रत्ययान्तं समासप्रातिपदिकं न भवति ॥ परत्वात्कबिति । सावकाशश्च कप् बहुयवागूक इत्यादौ ॥ अन्तरङ्गमिति । उपसर्जनस्त्रीप्रत्ययान्तप्रातिपदिकमात्रापेक्षत्वात् । कप् तु समासविशेषं बहुव्रीहिं नद्युत्तरपदमपेक्षत इति बहिरङ्गः ॥ अन्तरङ्गतर इति । पराभ्युपगमापेक्षया प्रकर्षप्रत्ययः ॥

(उद्योतः) समासान्त इतीति । कबन्तरङ्गतर इति वक्ष्यमाणोभिप्रायः ॥ बहुयवागूक इति । यवागूशब्दो दीर्घान्त इत्युक्तत्वात्तस्याप्राप्तेः स न स्त्रीप्रत्ययान्त इति भावः ॥ विशेषापेक्षत्वाद्बहिरङ्गत्वेप्याह—नद्युत्तरपदमिति ॥ ननु द्वयोः स्पर्धमानयोरेकस्य बहिरङ्गत्वे तदपेक्षमन्यस्यान्तरङ्गत्वमिति प्रकर्षाभावादातिशयिकोऽयुक्तोत आह—परेति । यदि भवान् ह्रस्वत्वमन्तरङ्गं मन्यते, तदा ततोप्यन्तरङ्गतरः कबित्यर्थः ॥

(आक्षेपभाष्यम्)

न चायं कप् समासान्त इत्युच्यते ॥

(आक्षेपबाधकभाष्यम्)

तादर्थ्यात्ताच्छब्द्यं भविष्यति । येषां पदानां समासः न तावत्तेषामन्यद्भवति कप् तावत् प्रतीक्षते ॥

(प्रदीपः) तादर्थ्यादिति । ततश्चावयवापेक्षत्वात्कपः समुदायापेक्षो ह्रस्वो बहिरङ्गः ॥

(उद्योतः) ततश्चावयवापेक्षत्वादिति । समासशब्देन तदर्थमुत्तरपदं लक्ष्यत इति भाव इति कश्चित् ॥ वस्तुतस्तु समासार्थे

विग्रहवाक्यं कथ्यत इति भाष्याशयस्तथैवान्यत्र दृष्टत्वात् । 'येषां पदानां समासो न तावत्तेषामन्यद्भवति' इति वाक्यशेषस्वारस्याच्च, एवं चान्तरङ्गतरत्वं स्पष्टमेव । कैयटेपि—अवयवापेक्षत्वादित्यस्यावयवगतप्रातिपदिकसंज्ञापेक्षत्वादित्यर्थः । समासान्तविधायकानां च तत्तत्समासार्थविग्रहवाक्यान्तावयवः शरदादिप्रातिपदिकात्परः प्रत्यय इत्यर्थ इति भावः ॥ समुदायापेक्ष इत्यस्य च समुदायगतप्रातिपदिकत्वापेक्ष इत्यर्थः । एवं च समाससंज्ञापेक्षसमुदायगतप्रातिपदिकत्वात्पूर्वमेव समासान्त इत्यन्तरङ्गतर इति भावः ॥ अन्त इति सूत्रस्थभाष्यात्समासावयवत्वस्यैव प्रतीतेः ॥ न तावत्तेषामिति । कपः प्रथममित्यर्थः ॥ अन्यत् । समासशास्त्रम् ॥ कपं तावदिति । तच्छास्त्रवैयर्थ्यभिया तद्भवनकालं प्रतीक्षत इत्यर्थः । अन्यथा समासशास्त्रस्य कबनपेक्षत्वेन तत्प्रतीक्षोक्तेरसंगतिः । एवं च कपा समकालं तत्पूर्वभागस्य समाससंज्ञा कपस्तद्वाक्यान्तावयवत्वेन समासप्रातिपदिकावयवत्वात्स्त्रीप्रत्ययस्य तदन्तत्वाभाव इति भावः ॥

(द्वन्द्वविषयकोक्तिभाष्यम्)

द्वन्द्वेप्युक्तम् ॥ किमुक्तम्? ॥ *परवल्लिङ्गमिति शब्दशब्दार्थौ* इति । तत्रौपदेशिकस्य ह्रस्वत्वमातिदेशिकस्य श्रवणं भविष्यति ॥ गोस्त्रियोः ॥ ४८॥

(प्रदीपः) द्वन्द्वेप्युक्तमिति । परिहारान्तरमप्यत्रास्ति—अवयवार्थावेव परस्परसहितौ द्वन्द्वार्थ इति प्राधान्यादुपसर्जनत्वाभाव इति ॥ ४८ ॥

(उद्योतः) प्राधान्यादिति । इदं परवल्लिङ्गं चार्थे द्वन्द्व इति सूत्रभाष्यविरोधाद् द्वन्द्वे च प्रतिषेध इति वार्तिकविरोधाच्च चिन्त्यम् । तस्माद्वचनारम्भ एव ज्यायान् । ध्वनितं चेदमनर्थकत्वमुक्त्वा द्वन्द्वे चेति निषेधं वदता दूषयिष्यमाणसमाधानोक्त्या च भगवतेति बोध्यम् ॥ शब्दशब्दार्थाविति परिहारस्तु परमयुवतिरित्यादौ तिप्रत्ययद्वयापत्त्या तत्रैव भाष्ये दूषित इति दिक् ॥ ४८ ॥

(१०१ लुग्विधिसूत्रम् ॥ १ । २ । २ आ. ५ सू.)

१२३ लुक्तद्धितलुकि ॥ १ । २ । ४९ ॥

(अनिष्टपरिहाराधिकरणम्)

(६९५ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ तद्धितलुक्यवन्त्यादीनां प्रतिषेधः ॥ * ॥

(भाष्यम्) तद्धितलुक्यवन्त्यादीनां प्रतिषेधो वक्तव्यः । अवन्ती । कुन्ती । कुरूः ॥

(प्रदीपः) लुक्तद्धित ॥४९॥ अवन्त्यादीनामिति । अवन्तीत्यत्र भवत्यवन्तिशब्द उपसर्जनं स्त्रीप्रत्ययश्चास्ति, लुक् च तद्धितस्य कृत इत्यस्ति लुक्प्राप्तिः ॥

(उद्योतः) लुक्तद्धित ॥ ४९ ॥ ननूपसर्जनस्येत्यत्र वर्तते तत्रावन्तिकुन्तिभ्यां वृद्धेदिति ञ्यङः, कुरोः कुर्वादिभ्य इति ण्यस्य च तद्राजस्य स्त्रियामवन्तिकुन्तिकुरुभ्यश्चेति लुकि, इतो मनुष्येति ऊङुत इति च ङीपूङोः कृतयोः स्वयपत्यवृत्तिस्त्रीप्रत्ययान्तस्यानुपसर्जनत्वात्तद्धितलुगनन्तरं स्त्रीप्रत्ययोत्पत्तेस्तत्परत्वाभावाच्च कथं लुक्प्राप्तिरत आह—अवन्तीत्यत्रेति । उपसर्जनसंबन्धिस्त्रीप्रत्ययस्य लुगित्यर्थस्तद्धितलुकीति च सत्सप्तमीत्याशयेन चोद्यमिति भावः ॥

(६९६ आक्षेपबाधकवार्तिकम् ॥ २ ॥)

॥ * ॥ तद्धितलुक्यवन्त्यादीनामप्रतिषेधोऽलुक्परत्वात् ॥ * ॥

(भाष्यम्) तद्धितलुक्यवन्त्यादीनामप्रतिषेधः । अनर्थकः प्रतिषेधोऽप्रतिषेधः ॥ लुकस्मान्न भवति? । अलुक्परत्वात् । लुकीत्युच्यते, न चात्र लुकं पश्यामः ॥

(प्रदीपः) अलुक्परत्वादिति । यत्र स्त्रीप्रत्ययान्तात्परस्य तद्धितस्य लुक् तत्र लुका भाव्यम्, अत्र तु कृते लुकि स्त्रीप्रत्ययः कृतः ॥

(उद्योतः) नास्ति लुक्परो यस्मात्स्त्रीप्रत्ययादित्यलुक्परत्वादित्यस्यार्थः ॥ कृते इति । एवं च न तत्परत्वं ङ्यादेरिति भावः ॥

(आक्षेपसाधकभाष्यम्)

लुकीति नैषा परसप्तमी शक्या विज्ञातुम् । नहि लुका पौर्वापर्यमस्ति ॥ का तर्हि? ॥ सत्सप्तमी लुकि सतीति ॥ सत्सप्तमी चेत् प्राप्नोति ॥

(प्रदीपः) नहीति । लुको नीरूपत्वाद् ॥ बुद्धिपरिकल्पितं तु लुकः परत्वमाश्रित्य वार्तिककृतोक्तमलुक्परत्वादिति ॥

(उद्योतः) कथं तर्हि वार्तिककृता 'अलुक्परत्वात्' इत्युक्तं तत्राह—बुद्धीति ॥

(समाधानभाष्यम्)

एवं तर्हीदमिह व्यपदेश्यं सद् आचार्यो न व्यपदिशति ॥ किम्? ॥ उपसर्जनस्येति वर्तते इति । न च जातिरुपसर्जनम् ॥ लुक्तद्धि—॥ ४९ ॥

(प्रदीपः) न च जातिरिति । उपसर्जनग्रहणेन स्त्रीप्रत्ययो विशेष्यते । अप्रधानं चेहोपसर्जनं गृह्यते, न शास्त्रीयमसंभवात् । अवन्तीत्यत्र चापत्यलक्षणा जातिः स्त्रीत्वयुक्ता प्राधान्येनाभिधीयत इत्यर्थः । अप्रातिपदिकत्वाच्चात्र ह्रस्वाभावः । आमलकमित्यादौ तु तद्धितान्तत्वात्प्रातिपदिकसंज्ञा । लिङ्गविशिष्टस्यैवेहोपादानाल्लिङ्गविशिष्टपरिभाषाया उपस्थानाभावः । कुरूरित्यत्रापि उभयत आश्रयणे नान्तादिवदित्यप्रातिपदिकत्वम् ॥ ४९ ॥

(उद्योतः) उपसर्जनसंबन्धिन इत्यर्थात् न च जातिरुप-

सर्जनमित्ययुक्तमत आह—उपसर्जनेति । सम्भवति सामानाधिकरण्ये वैयधिकरण्यमन्याय्यमिति भावः ॥ इह । लुग्विधायके ॥ स्त्रीत्वयुक्तप्राधान्येनेति । एवं च प्रधानजातिगतस्त्रीत्वाभिधायी प्रत्ययो नोपसर्जनमिति भावः ॥ स्वयं लुगभावे ऐत्वन्तरमाह—अप्रातिपदिकत्वाच्चात्र ह्रस्वाभाव इति । अत्रावन्तीत्यादौ । लुक्पदेन ह्रस्वप्रयोजको लुगुच्यते, स्त्रीलुकि हि अवन्तिरिति ह्रस्वमवतिष्ठत इति तत्प्रयोजकता लुको बोध्या । तद्धितलुकि स्त्रीप्रत्ययान्तप्रातिपदिकावयवस्य प्रत्यासत्त्या स्त्रीप्रत्ययस्य लुगिति सूत्रार्थः, प्रकृते च न तत्त्वं, तद्धितान्तात्स्त्रीप्रत्ययोत्पत्तेरिति भावः ॥ गोस्त्रियोरिति ह्रस्वस्य तु नात्र प्राप्तिस्तत्र शास्त्रीयोपसर्जनस्य ग्रहणात् । यथा चैतत्तथोपपादितम् । क्वचित्तु लुगभाव इत्येव पाठः ॥ नन्वेवं कथमामलकमित्यादौ लुगत आह—आमलकेति ॥ तद्धितान्तत्वादिति । मयटो लुकि प्रत्ययलक्षणेनेति भावः ॥ ननु लिङ्गविशिष्टपरिभाषया प्रातिपदिकग्रहणानुवृत्त्यावन्त्यन्तीत्यत्र दोषेत आह—लिङ्गेति । लिङ्गविशिष्टस्योपादानेपि तत्परिभाषाप्रवृत्तौ बाधकाभावेन भाष्योक्तसमाधिरेव युक्त इति बोध्यम् ॥ ४९ ॥

(१०२ ह्रस्वविधिसूत्रम् ॥ १ । २ । २ आ. ६ सू.)

१२४ इड्गोण्याः ॥ १ । २ । ५० ॥

(६९७ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ इड्गोण्या नेति वक्तव्यम् ॥ * ॥

(भाष्यम्) गोण्या नेत्येव सिद्धम् । नार्थ इत्त्वेन ॥

(उद्द्योतः) इड्गोण्याः ॥ ५० ॥ पञ्चभिर्गोणीभिः क्रीत इति द्विगौ क्रीतार्थठको लुकि लुक्तद्धितेति लुगपवादभूतमिदं सूत्रम् । तत्रानेन लुको निषेधे एकविभक्तीत्युपसर्जनत्वाद्ध्रस्वेन सिद्धे इद्ग्रहणं व्यर्थमिति चोद्यम् ॥

(प्रत्याक्षेपभाष्यम्)

का रूपसिद्धिः—पञ्चगोणिर्दशगोणिः ? ।

(६९८ प्रत्याक्षेपसमाधानवार्तिकम् ॥ २ ॥)

॥ * ॥ ह्रस्वता हि विधीयते ॥ * ॥

(भाष्यम्) ह्रस्वत्वमत्र विधीयते "गोस्त्रियोरुपसर्जनस्य" इति ॥

(६९९ समाधानवार्तिकम् ॥ ३ ॥)

॥ * ॥ इति वा वचने तावत् ॥ * ॥

(भाष्यम्) इदित्येवोच्येत नेति वा । को न्वत्र विशेषः ॥

(प्रदीपः) इड्गोण्याः ॥५०॥ इति वा वचन इति । इतीति सप्तमी । इच्छब्देऽप्युच्यमाने गौरवाभाव इत्यर्थः ॥

(उद्द्योतः) समाधत्ते—भाष्ये इति वा वचने तावदिति । इच्छब्दोक्तौ नशब्दोक्तौ च तावदेव, न तु मात्राप्यधिकेति तदर्थः ॥

(७०० समाधानान्तरवार्तिकम् ॥ ४ ॥)

॥ * ॥ मात्रार्थं वा कृतं भवेत् ॥ * ॥

(भाष्यम्) अथ वा मात्रार्थमिदं वक्तव्यम् । गोणीमात्रमिदं गोणिः ॥

(प्रदीपः) गोणिरिति । यदा मात्रचो लुक् क्रियते तदा लुकि प्रतिषिद्धे सिध्यत्येव ह्रस्वत्वम् । तस्मात्प्रथमाविधाने परिमाणग्रहणस्य प्रयोजनम्—तद्धितमन्तरेणापि यदा परिमाणशब्दः परिमेये वर्तते तदापि प्रथमा यथा स्यादिति । एवं चानुपसर्जनत्वादभेदोपचारेण प्रमेयवृत्तित्वादप्राप्तो ह्रस्व इति इत्त्वं विधीयते ॥ सर्वत्र तर्हि गोण्या इत्त्वप्रसङ्गः । एवं तर्ह्युपसर्जनस्येति वर्तते, न तु तद्धितलुकीति । तेन यत्र स्वार्थोपसर्जनमर्थान्तरं प्रत्याय्यते तत्रेत्त्वविधिः । ह्रस्वत्वं तु न स्यादप्रातिपदिकत्वात् ॥

(उद्द्योतः) लुकि । स्त्रीप्रत्ययलुकि ॥ सिध्यत्येव ह्रस्वत्वमिति । गोवष्कयणीत्यादौ ह्रस्वपारणाय शास्त्रीयोपसर्जनस्य तत्र ग्रहाचिन्त्यमिदम् । भाष्यं तु यथाश्रुतं रमणीयमेव ॥ तदापि प्रथमेति । प्रस्थादिभ्यः परिच्छेदकवाचिभ्यः प्रमेयविवक्षायां प्रथमां बाधित्वा तद्धितः प्राप्नोति, तदविवक्षायां प्रातिपदिकार्थत्वादेव सिध्यतीति व्यर्थं तदित्याशङ्क्य तद्धितमन्तरेणापि यदा परिमाणेत्यादि प्रातिपदिकार्थसूत्रे वक्ष्यतीति भावः । न चानुपसर्जनत्वादित्वमपि न प्राप्नोति, तस्येहासंबन्धादिति भावः ॥ अभेदोपचारेणेति । गोण्येव व्रीहय इत्याद्यर्थबुध्या गोणीशब्दस्य प्रमेयवृत्तितया लाक्षणिकत्वेनानुपसर्जनत्वमित्यर्थः ॥ तत्र शङ्कते—सर्वत्र तर्हीति ॥ तेन यत्रेति । लाक्षणिकस्याप्युपसर्जनत्वं मन्यते । एवं हि गोणीसदृशे लक्षणायामपि ह्रस्वापत्तेश्चिन्त्योयं कैयटः ॥ तर्हि ह्रस्वत्वेनैव सिद्धे व्यर्थ इद्विधिः स्यादत आह—ह्रस्वत्वं त्विति ॥ अप्रातिपदिकत्वादिति । गोणीशब्दस्य ङ्यन्तत्वादिति भावः ॥ प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहादप्रातिपदिकत्वादिति चिन्त्यम् ॥

(भाष्यम्) अपर आह—

(७०१ आक्षेपवार्तिकम् ॥ ५ ॥)

॥ * ॥ गोण्या इत्त्वं प्रकरणात् ॥ * ॥

(भाष्यम्) अशिष्यं गोण्या इत्त्वम् ॥ किं कारणम् ? । प्रकरणात् । प्रकृतं ह्रस्वत्वम् । ह्रस्व इति वर्तते ॥

(प्रदीपः) अशिष्यमिति । गोस्त्रियोरित्यस्यानन्तरं गोण्या इति लुगपवादह्रस्वार्थं वक्तव्यम् ॥

(उद्द्योतः) ननु लुका विच्छिन्नत्वात्कथं ह्रस्वानुवृत्तिरत आह—गोस्त्रियोरिति । लुगपवादेऽनेनोपसर्जनस्येत्यनुवृत्तिं दर्शयति ॥

(आक्षेपभाष्यम्)

न तु सूच्याः ।

(प्रदीपः) न तु सूच्या इति । इत्त्वं प्राप्नोतीति शेषः ॥ क्वचित्तु ननु सूच्या इति पाठः । तत्रेत्त्वमिष्यत इत्यध्याहारः ॥

(उद्द्योतः) तत्रेत्वमिष्यते इति । तच्च न सिध्यतीति शेषः ॥

(७०२ समाधानवार्तिकम् ॥ ६ ॥)

॥ * ॥ सूच्याद्यर्थमथापि वा ॥ * ॥

(भाष्यम्) सूच्याद्यर्थमिदं द्रष्टव्यम् । पञ्चसूचिः । दशसूचिः ॥

इद्गोण्या नेति वक्तव्यं ह्रस्वता हि विधीयते ।
इति वा वचने तावन्मात्रार्थं वा कृतं भवेत् ।
गोण्या इत्त्वं प्रकरणात् सूच्याद्यर्थमथापि वा १॥
इद्गोण्याः ॥ ५० ॥

(प्रदीपः) इद्ग्रहणे सति योगविभागो लभ्यते । गोणिरिति तु मात्रचो लोपेन सिद्ध्यति ॥ ५० ॥

(उद्द्योतः) इद्ग्रहणे यथा सिध्यति तदाह—योगेति इदित्येको योगो लुगपवादार्थः । गोण्या इति द्वितीयस्तस्यासार्वत्रिकत्वायेति नातिप्रसङ्ग इति भावः ॥ नन्वस्य लुगपवादत्वे यत्र प्रमेयलक्षणया गोणीशब्दप्रयोगस्तत्र लुगभावादित्त्वमपि न स्यादत आह—गोणिरिति ॥ लोपेनेति । लुकेत्यर्थः । एवं च कैयटस्य पूर्वापरविरोधोपि द्रष्टव्यः । अत्र पक्षे लक्षणायां गोणी इति दीर्घान्तस्यैवेष्टत्वादित्याहुः ॥ ५० ॥

(१०३ युक्तवद्भावातिदेशसूत्रम् ॥ १ ।२। २ आ. ७ सू.)

१२५ लुपि युक्तवद्व्यक्तिवचने ॥ १ । २ । ५१ ॥

(प्रदीपः) लुपि ॥ ५१ ॥ प्रकृत्यर्थसंबन्धिन्यौ लिङ्गसंख्ये प्रत्ययार्थे अतिदिश्येते ॥

(उद्द्योतः) लुपि यु ॥ ५१ ॥ पदार्थानवगमे तद्व्यावर्त्यमवगन्तुं न शक्यतेऽतः सूत्रार्थमाह—प्रकृतीति । युक्तशब्देन प्रकृत्यर्थ उच्यते स हि प्रत्ययार्थेन युक्तो भवति । प्रकृतौ यादृशं लिङ्गसंख्याप्रयुक्तं कार्यं तत्प्रत्ययार्थप्रतिपादिकायां तत्रादिश्यत इति तात्पर्यम् ॥ व्यक्तिर्लिङ्गं वचनं संख्या ॥

(पदकृत्यवर्णनाधिकरणम्)

(आक्षेपभाष्यम्)

व्यक्तिवचने इति किमर्थम् ? ॥

(समाधानभाष्यम्)

शिरीषाणामदूरभवो ग्रामः शिरीषाः तस्य ग्रामस्य वनं शिरीषवनम् ॥ किं च स्यात् ? ॥ "विभाषौषधिवनस्पतिभ्य" इति णत्वं प्रसज्येत ॥

(प्रदीपः) शिरीषा इति । वरणादित्वादणो लुप् । ग्रामवाचित्वाद्वनस्पतिवाचित्वाभावाण्णत्वाभावः । फली वनस्पतिर्ज्ञेय इत्ययं भेदो णत्वविधौ नाश्रित इति फलाभावेपि शिरीषस्यास्ति वनस्पतित्वम् ॥

(उद्द्योतः) नन्वपुष्पः फलवान् वनस्पतिस्तथा च शिरीषस्य कथं वनस्पतित्वं यद्ग्राममितिदिश्येतेत्यत आह—फलीति । अस्यापुष्प इत्यादिः ॥ फलाभावेपीत्यस्यापुष्पफलाभावेपीत्यर्थः । यद्वा शिम्बीनां फलत्वाभावं मन्यते । एवं च वनस्पतिशब्देन वृक्ष एवोच्यत इति भावः ॥

(मतान्तरेणसमाधानभाष्यम्)

अपर आह—कटुकबदर्या अदूरभवो ग्रामः कटुकबदरी । षष्ठी युक्तवद्भावेन मा भूदिति ॥

(प्रदीपः) षष्ठीति । प्रकृत्यर्थगतस्य व्यतिरेकस्य प्रत्ययार्थेतिदेशात्षष्ठीप्रसङ्गः ॥

(उद्द्योतः) षष्ठ्याः प्रकृत्यर्थधर्मत्वाभावात्कथमतिदेशोत आह—प्रकृत्यर्थेति । व्यतिरेकस्य संबन्धस्य ॥

(प्रत्याक्षेपभाष्यम्)

अथ व्यक्तिवचने इत्यप्युच्यमाने कस्मादेवात्र न भवति । षष्ठ्यपि हि वचनम् ? ॥

(प्रदीपः) षष्ठ्यपीति । वचनशब्देन ह्येकवचनादयः प्रत्यया उच्यन्ते । तत्र वाक्यावस्थायां षष्ठीदर्शनात्तस्या एवात्रातिदेशः प्राप्नोति ॥

(उद्द्योतः) षष्ठ्या एव प्रसङ्गे हेतुमाह—तत्रेति । युक्तशब्देन प्रकृतिस्तद्वल्लिङ्गमेकवचनादिप्रत्ययाश्च लुपि सति भवन्तीति सूत्रार्थः । अर्थशब्दयोरभेदाच्च लिङ्गस्य प्रकृतिनिष्ठत्वम् । एवं चोपस्थितत्वात्तस्या एवातिदेशः प्राप्नोतीति भावः ॥

(प्रत्याक्षेपसमाधानभाष्यम्)

नेदं पारिभाषिकस्य वचनस्य ग्रहणम् ॥ किं तर्हि ? । अन्वर्थग्रहणम्—उच्यते वचनमिति ॥

(प्रदीपः) नेदमिति । एकवचनादिसंज्ञाविधानकाले अनुनिष्पादी वचनशब्दोपि संज्ञात्वेन नियुक्त इति प्रत्ययः पारिभाषिकं वचनमुच्यते ॥ अन्वर्थग्रहणमिति । संख्यालक्षणोर्थोतिदिश्यत इत्यर्थः ॥

(उद्द्योतः) ननु वचनमिति पारिभाषिकसंज्ञाभावाद्भेदमित्यसंङ्गतमत आह—एकवचनादीति ॥ अनुनिष्पादीति । नान्तरीयक इत्यर्थः ॥ भाष्ये अन्वर्थेति । लौकिकः संख्यारूपोर्थो वचनशब्देनोच्यत इति भावः । अन्वर्थत्वमत्र लोकप्रसिद्धार्थत्वम् ॥

(समाधानबाधकभाष्यम्)

एवमपि षष्ठी प्राप्नोति । षष्ठ्यपि लुप्यते ॥

(प्रदीपः) षष्ठ्यपि लुप्यत इति । संख्यातिदेशे तद्वचनेन शब्देन प्रवर्तितव्यम् । षष्ठ्यपि संख्यायाः प्रतिपादिकेति भावः । षष्ठीशब्देन च षष्ठ्यर्थः संख्यालक्षणोऽभिधीयते ॥ अथ वा षष्ठ्यप्युच्यते संख्याप्रतिपादनार्थमित्यर्थः ॥

(उद्योतः) नन्वेवं षष्ठ्यप्युच्यत इत्यनुपपन्नमत आह— षष्ठीशब्देन चेति ॥

(समाधानसाधकभाष्यम्)

लुपोक्तत्वात्तस्यार्थस्य द्वितीयस्य प्रयोगेण न भवितव्यम् ॥ किं कारणम् ? । उक्तार्थानामप्रयोग इति ॥

(प्रदीपः) लुपोक्तत्वादिति । लुप्सहचरितेन शब्देनोक्तत्वादित्यर्थः । अभिहितः सोऽर्थोन्तर्भूतः प्रातिपदिकार्थः संपन्न इति व्यतिरेकाभाव इत्यर्थः ॥

(उद्योतः) ननु लुपोभावस्य कथमभिधायकत्वं किं च लुपादूरमवार्थोक्तावपि षष्ठ्यर्थस्य कथमुक्तिरत आह—लुप्सहचरितेनेति । तेन हि स्वसंबन्धदूरभव उच्यत इति भावः ॥ तदाह— अभिहित इति ॥ व्यतिरेकाभाव इति । भेदनिबन्धनसंबन्धस्याभाव इत्यर्थः । शेषत्वाभाव इति यावत् । कारकप्रातिपदिकार्थव्यतिरिक्तो हि शेषः ॥

(आक्षेपभाष्यम्)

आतिदेशिकी तर्हि प्राप्नोति ॥

(प्रदीपः) आतिदेशिकीति । संख्यायामतिदिष्टायां तद्वाची शब्दः प्रयोक्तव्यः । वाक्ये च षष्ठी दृश्यते इति तस्या एव प्रसङ्गः ॥

(उद्योतः) षष्ठ्यतिदेशाभावेनातिदेशिकीत्ययुक्तमत आह— संख्यायामिति ॥

(समाधानशेषभाष्यम्)

एवं तर्हि—

(७०३ समाधानवार्तिकम् ॥ १ ॥)

॥ * ॥ प्रागपि वृत्तेर्युक्तं वृत्तं चापीह यावता युक्तम् । वक्तुश्च कामचारः प्राग्वृत्तेर्लिङ्गसंख्ये ये ॥ * ॥

(भाष्यम्) प्रागपि वृत्तेर्युक्तं वनस्पतिभिर्नगरम् । वृत्तं चापि युक्तं वनस्पतिभिर्नगरम् । वृत्ते च युक्तवद्भावो विधीयते । कामचारश्च प्रयोक्तुः— प्राग्वृत्तेर्ये लिङ्गसंख्ये ते अतिदेष्टुम्, वृत्तस्य वा ये लिङ्गसंख्ये ते । यावता कामचारः । वृत्तस्य ये लिङ्गसंख्ये ते अतिदेक्ष्येते, न प्राग्वृत्तेर्ये ॥

(प्रदीपः) प्रागपीति । प्रत्ययार्थेन प्रकृतिवाच्यं वस्तु संबद्धं वाक्यावस्थायां वृत्त्यवस्थायां चेत्यर्थः ॥ वक्तुश्चेति चशब्दो भिन्नक्रमः प्राग्वृत्तेरित्यस्यानन्तरं द्रष्टव्यः । ततश्चायमर्थः—प्राग्वृत्तेर्ये लिङ्गसंख्ये चशब्दात् वृत्तस्य ये, ते अतिदेष्टुं कामचारः ॥ वृत्तस्येति । प्रत्यासत्त्येति भावः ॥ वृत्तावुपसर्जनस्यापि क्वचित्संख्याविशेषावगतिर्भवति । यथा तावकीनो मामकीन इत्यादेशात् संख्याभेदावगमः । तथेह प्रत्ययार्थे अतिदिष्टसंख्यावगमात् प्रकृत्यर्थे तदवसायः । यथा आदेशे प्रथमासामानाधिकरण्यदर्शनात् लटि तदवगतिः । तत्र च वृत्तावुपसर्जनं प्रधानार्थमभिधत्त इति व्यतिरेकाभावात् संख्यामात्रप्रतिपद्धा प्रातिपदिकार्थमात्रे प्रथमैव भवति ॥

क्वचिदधिको ग्रन्थः पठ्यते—

अथ वा प्राग्वृत्तेर्ये लिङ्गसंख्ये ते अतिदेक्ष्येते । षष्ठी कस्मान्न भवति । सामान्यातिदेशे विशेषानतिदेश इति ॥

तत्रायमर्थः—वाक्यावस्थायां प्रकृत्यर्थस्य ये लिङ्गसंख्ये ते अतिदिश्येते षष्ठी तु व्यतिरेकनिबन्धना । न चेह प्रत्ययार्थस्य व्यतिरेकोस्ति । न च व्यतिरेकसहिता संख्या अतिदिश्यते । संख्यामात्रातिदेशे संबन्धसहितसंख्यातिदेशाभावात् ॥

(उद्योतः) चेत्यर्थ इति । फलं तु विशेषः—वाक्ये भिन्नोपस्थितिविषयतया वृत्तौ, चैकोपस्थितिविषयतयेति ॥ उत्तरार्धे पक्षान्तराप्रतीतेः कामचार इत्ययुक्तमत आह—चशब्द इति । तथा च तेन पक्षान्तरद्योतनमस्तीति भावः ॥ भाष्ये उक्तश्लोकस्य व्याख्यानं प्रागपि वृत्तेर्युक्तं वनस्पतिभिरित्यादि कामचारविषये एकतरपक्षग्रहणे विनिगमकाभावेत आह—प्रत्यासत्त्येति । तदुक्तं भाष्ये वृत्ते च युक्तवद्भावो विधीयत इति ॥ वृत्तिप्राक्कालावच्छिन्नार्थनिष्ठलिङ्गसंख्ययोरतिदेश, उत वृत्तिकालावच्छिन्नयोरिति संशयः । तत्राद्ये संख्यायाः षष्ठीप्रतिपाद्यसंबन्धवदर्थनिष्ठत्वात्तादृशयोरेवातिदेशे षष्ठी स्यादिति चोद्यम् । द्वितीयमादायोत्तरम् । तत्र प्रातिपदिकप्रतिपाद्यसंबन्धवदर्थनिष्ठत्वात् तादृशयोरेवातिदेशे प्रातिपदिकार्थमात्रत्वात्प्रथमैव । अतिदेशस्य वृत्तिनिष्ठत्वात्तद्गतयोरेवातिदेशे एकनिष्ठत्वं प्रत्यासत्तिरिति बोध्यम् ॥ ननु वृत्तावुपसर्जनार्थस्य संख्याभेदानवगतेः कथं तत्कालावच्छिन्नतदतिदेशोत आह—वृत्तावुपेति । आदेशात् । तवकममकावेकवचन इति विहितात् ॥ तत्र चैतैनत्वाविनैकस्यैवोपस्थितिर्न त्वेकत्वेनेति तत्त्वम् ॥ तथेहेति । शिरीषा ग्राम इति बहुवचनात्तत्प्रकृत्यापि शिरीषत्वेनानेकोपस्थितिर्न तु बहुत्वेनेति तत्त्वम् । अन्यथातिदेशाप्राप्त्या तदनुपपत्तिरिति भावः ॥ ननु संख्यातिदेशेऽपि तन्निबन्धना षष्ठी कस्मान्नेत्यत आह—वृत्तावुपसर्जनमिति ॥ व्यतिरेकाभावादिति । तदतिदेशस्य न मानाभावादिति भावः ॥ अथ वा प्राग्वृत्तेरिति । इदमयुक्तं प्रत्यासत्तिबाधापत्तेरित्याहुः ॥

(आक्षेपभाष्यम्)

किमर्थं पुनरिदमुच्यते ? ।

(प्रदीपः) किमर्थमिति । अन्तरेणाप्यतिदेशं लिङ्गसंख्ये सिद्धे । यथाऽऽपो दारा इत्यादाविति प्रश्नः ।

(उद्द्योतः) ननु तद्धितार्थस्यैकत्वादेकवचननिवृत्तयेऽवश्याश्रयणीयोतिदेशोत आह—अन्तरेणापीति ॥

(७०४ समाधानवार्तिकम् ॥ २ ॥)

॥ * ॥ अन्यत्राभिधेयस्य व्यक्तिवचनभावाल्लुपि युक्तवदनुदेशः ॥ * ॥

(भाष्यम्) अन्यत्राभिधेयवल्लिङ्गवचनानि भवन्ति ॥ क्वान्यत्र ? ॥ लुकि । लवणः सूपः । लवणा यवागूः । लवणं शाकमिति । अन्यत्राभिधेयवद्व्यक्तिवचनानि भवन्ति लुकि । इहाप्यभिधेयवल्लिङ्गवचनानि प्राप्नुवन्ति । इष्यन्ते चाभिधानवत्स्युरिति । तच्चान्तरेण यत्नं न सिध्यतीति लुपि युक्तवदनुदेशः । एवमर्थमिदमुच्यते ॥

(प्रदीपः) अन्यत्रेति । अभेदं लिङ्गसंख्ययोराश्रित्य वार्तिककारेण पठितम् । भाष्यकारस्तु वाचकभेदनिबन्धनभेदावसायेन वतिना व्याचष्टे अभिधेयवदिति । अभिधानवदिति । अभिधानशब्देनोपसर्जनमभिधीयते । तेन हि प्रधानार्थोऽभिधीयते । तस्य चार्थद्वारको लिङ्गसंख्यायोगः ॥

(उद्द्योतः) भाष्यवार्तिकयोर्वैतिप्रयोगाप्रयोगयोर्बीजमाह—अभेदमिति ॥ लिङ्गसंख्ययोरिति । विशेष्यमात्रगतलिङ्गसंख्ययोर्विशिष्टगतलिङ्गसंख्ययोश्चेत्यर्थः ॥ पठितमिति । अभिधेयस्य व्यक्तीति पठितमित्यर्थः ॥ वतिनेति । विशेष्यमात्रवाचके यल्लिङ्गसंख्याम्युक्तं कार्यं दृश्यते तद्वदेवान्यत्र विशिष्टवाचकेपि दृश्यते तथा प्रकृतेपि स्यात्तद्वारणार्थं सूत्रमिति भावः ॥ अभिधेयम् । विशेष्यम् ॥ अभिधानशब्दस्य वाचकपर्यायत्वादभिधानवदित्ययुक्तमत आह—उपसर्जनमिति ॥ तत्र योगं दर्शयति—तेन हीति ॥ प्रधानार्थः । तदास्कन्दितस्वार्थः ॥ तस्य चेति । त्रिलिङ्गोऽयं शब्द इत्यादिप्रयोगदर्शनादिति भावः ॥

(काकुभाष्यम्)

अस्ति प्रयोजनमेतत् ॥ किं तर्हीति ॥

(अर्थे कार्यसाधकाधिकरणम्)

(७०५ आक्षेपवार्तिकम् ॥ ३ ॥)

॥ * ॥ लुपोऽदर्शनसंज्ञित्वादर्थगतिर्नोपपद्यते ॥ * ॥

(भाष्यम्) लुब्नामेयमदर्शनस्य संज्ञा क्रियते । न चादर्शनस्य लिङ्गसंख्ये शक्येते अतिदेष्टुम् । लुपोऽदर्शनसंज्ञित्वादर्थगतिर्नोपपद्यते ॥

(उद्द्योतः) भाष्ये लुपोदर्शनसंज्ञित्वादिति । लुपः लुप्शब्दस्य ॥ ननु लुपीत्यनेन प्रत्ययार्थो वाच्य इत्यत आह—अदर्शनसंज्ञित्वादिति । बहुव्रीहिः ॥

(७०६ समाधानवार्तिकम् ॥ ४ ॥)

॥ * ॥ न वाऽदर्शनस्याशक्यत्वादर्थगतिः साहचर्यात् ॥ * ॥

(भाष्यम्) न वा एष दोषः ॥ किं कारणम् ? । अदर्शनस्याशक्यत्वात् । अदर्शनस्य लिङ्गसंख्ये अशक्ये अतिदेष्टुमिति कृत्वा अदर्शनसहचरितो योर्थस्तस्य गतिर्भविष्यति । साहचर्यात् ॥

(प्रदीपः) न वाऽदर्शनस्येति । अभावरूपत्वादिति भावः ॥

(उद्द्योतः) न वाऽदर्शनस्येति । लुबर्थादर्शनस्येत्यर्थः । अशक्यत्वे हेतुमाह—अभावेति । स्वरूपसदभावे शब्दावाच्येतिदेशोऽशक्य इति भावः ॥ साहचर्यादिति । लुप्शब्देन लुपो यः स्थानी प्रत्ययस्तदर्थो लक्ष्यते तद्युक्तार्थस्य लिङ्गसंख्ये लुप्स्थानिप्रत्ययार्थेऽतिदिश्येते इति तात्पर्यम् ॥

(७०७ समाधानहेत्वन्तरवार्तिकम् ॥ ५ ॥)

॥ * ॥ योगाभावाच्चान्यस्य ॥ * ॥

(भाष्यम्) अन्यस्यादर्शनेन योगो नास्तीति कृत्वा अदर्शनसहचरितो योर्थस्तस्य गतिर्भविष्यति साहचर्यात् ॥

(प्रदीपः) योगाभावादिति । अदर्शनेन प्रकृत्यर्थो न युक्त इत्यर्थः ॥

(उद्द्योतः) युक्तः संबद्ध इति प्रकृत्यर्थ इत्युच्यते । तत्र केन युक्त इत्याकाङ्क्षायामुपस्थितत्वाल्लुबर्थस्यैव संबन्धः स्यात् । न च तदर्थादर्शनेन कस्यचिद् योग इति युक्तपदार्थाप्रसिद्धिरतोपि तत्स्थानिप्रत्ययार्थलाभ इत्यर्थकं भाष्ये—योगाभावाच्चेति ॥

(७०८ आक्षेपवार्तिकम् ॥ ६ ॥)

॥ * ॥ समास उत्तरपदस्य बहुवचनस्य लुपः ॥ * ॥

(भाष्यम्) समासे उत्तरपदस्य बहुवचनस्य लुपो युक्तवद्भावो वक्तव्यः । मधुरापञ्चालाः ॥ किं प्रयोजनम् ? ॥ नियमार्थम्—समास उत्तरपदस्यैव ॥ क मा भूत् ? ॥ पञ्चालमधुरे इति ॥ लुपि युक्तवत् ॥

(प्रदीपः) मधुरापञ्चाला इति। वर्तिपदार्था एवापेक्षितपरस्परा द्वन्द्वार्थ इति सिद्धे नियमः क्रियते। अत एव मधुरागोदा इति भवति न तु मधुरागोदाविति। द्वन्द्वेपि गोदार्थस्य द्विलानतिक्रमात्॥ ५१॥

(उद्योतः) नन्वेवमप्युद्भूतावयवसमूहस्यैव द्वन्द्वार्थत्वेन द्विवचनमेव स्यादिति बहुवचनसिध्यर्थोतिदेशः स्यादत आह—वर्तिपदेति। मधुरापञ्चाला इति भाष्ये उदाहृतत्वादिह समासशब्देनेतरेतरद्वन्द्व एवाभिधीयते। उत्तरसंख्यया पूर्वसंख्यायाधादतिदिष्टसंख्यामादाय बहुवचनम्। लुबन्तस्य पूर्वपदत्वे त्वतिदेशाभावाद् द्विवचनमेवेति भावः॥ अत एव वर्तिपदार्थप्राधान्यादेव॥ समासे बहुवचनान्तप्रकृतिकलुबन्तार्थे चेदतिदेशस्तदोत्तरपदस्यैवेति वार्तिकार्थो न तूत्तरपदस्य चेद्बहुवचनान्तस्यैवेत्यर्थ इति भावः॥ बहुवचनग्रहणं त्वबहुवचनान्तलुबन्तपूर्वपदस्य नियमेन व्यावृत्तिर्मा भूदिति, तेन गोदमधुरा इति भवति न तु गोदमधुरे इतीत्याहुः ५१

(९०७ युक्तवद्भावातिदेशसूत्रम् ॥ १।२।२ आ. ८ सू.)

१२६ विशेषणानां चाजातेः १।२।५२॥

(जातिपदार्थान्वयनिर्णयाधिकरणम्)

(आक्षेपभाष्यम्)

कथमिदं विज्ञायते जातिर्यद्विशेषणमिति, आहोस्विज्जातेर्यानि विशेषणानीति ? ॥

(प्रदीपः) विशेष ॥ ५२ ॥ कथमिति। किं सामानाधिकरण्येन सम्बन्धः,—विशेषणानां युक्तवद्व्यक्तिवचने आसिषु यदा विशेषणं तदा नेति। अथ वैयधिकरण्येन—जातेर्यानि विशेषणानि तेषां नेति। अजातेरिति चासमर्थसमासः, भवतिना नञः सम्बन्धात्। उभयथा चाव्याप्तिः प्रतिषेधस्येति प्रश्नः॥

(उद्योतः) विशेषणानां चा ॥ ५२ ॥ परिच्छेदकमत्र विशेषणम्॥ नञा समस्ताया जातेर्विशेषणानामित्यनेन कथमन्वयोत आह—असमर्थेति। एवं च नञ इवोत्तरपदार्थस्याप्यन्यत्रान्वयो न दोषायेति भावः॥ पूर्वसूत्रेण प्रकृत्यर्थगतलिङ्गसंख्ययोर्लुबर्थेतिदेशात्तद्विशेषणानामपि सिद्ध एवातिदेशः। लुबर्थविशेषणानां स्वविशेष्यगतलिङ्गवचनयोरुचितत्वात्। सूत्रं तु जातिप्रतिषेधार्थम्॥ तत्र संदेह इति तात्पर्यम्॥

(आक्षेपहेतुनिराकरणभाष्यम्)

किं चातः ? ॥

(आक्षेपसाधकभाष्यम्)

यदि विज्ञायते—जातिर्यद्विशेषणमिति। सिद्धम्—पञ्चाला जनपद इति। सुभिक्षः संपन्नपानीयः बहुमाल्यफल इति न सिध्यति॥

अथ विज्ञायते—जातेर्यानि विशेषणानीति सिद्धम्—सुभिक्षः संपन्नपानीयः बहुमाल्यफल इति। पञ्चाला जनपद इति न सिध्यति॥

(उद्योतः) भाष्ये—सुभिक्ष इत्यादि न सिध्यतीति। तेषां जनपदविशेषणत्वेपि तद्द्वारा लुबन्तविशेषणत्वस्यापि सत्त्वेन बहुवचनमेव स्यादीदृशविशेषणेषु विध्यर्थमेव विशेषणानामित्यंशः स्यादित्याशयः॥

(समाधानभाष्यम्)

एवं तर्हि नैवं विज्ञायते—जातिर्यद्विशेषणमिति, नापि—जातेर्यानि विशेषणानीति॥ कथं तर्हि? ॥ विशेषणानां युक्तवद्भावो भवति। आ जातेः। आजातिप्रयोगात्॥

(प्रदीपः) आजातिप्रयोगादिति। सूत्रे आङः प्रश्लेषो न तु नञः। अत्रायमर्थः—तावद्युक्तवद्भावो भवति यावज्जातिर्न प्रक्रान्ता। यदा तु जातिः प्रक्रम्यते विशेषणत्वेन विशेष्यत्वेन वा तदा युक्तवद्भावो न भवतीति॥

(उद्योतः) यदा तु जातिः प्रक्रम्यते इति। अत एव पञ्चालाः सुभिक्षा जनपद इति पञ्चाला जनपदः सुभिक्ष इत्येव च भवति जातौ प्रक्रान्तायां यद्विशेषणमुपनिपतितं तज्जातिमेव साक्षाद्विशिनष्टीति भावः। विशेषणानामित्यनेनापि साक्षाल्लुबर्थविशेषणग्रहणमेवोचितमिति तात्पर्यम्॥ जातिगुणसमभिव्याहारे जातेर्विशेष्यत्वनियमादाह—विशेष्यत्वेन वेति।

(भाष्यम्) **किमर्थं पुनरिदमुच्यते ? ।**

(उद्योतः) शङ्कते—भाष्ये—[अथ] किमर्थं पुनरिदमिति। विशेषणानामित्येतदित्यर्थः॥

(७०९ समाधानवार्तिकम् ॥ १ ॥)

॥ * ॥ विशेषणानां वचनं जातिनिवृत्त्यर्थम् ॥ * ॥

(भाष्यम्) **जातिनिवृत्त्यर्थोऽयमारम्भः॥**

(उद्योतः) उत्तरयति—जातिनिवृत्त्यर्थं इति॥

(आक्षेपभाष्यम्)

किमुच्यते जातिनिवृत्त्यर्थ इति। न पुनर्विशेषणानामपि युक्तवद्भावो यथा स्यादिति।

(उद्योतः) विशेषणानामिति। सुभिक्षादीनामित्यर्थः॥

(७१० समाधानवार्तिकम् ॥ २ ॥)

॥ * ॥ समानाधिकरणत्वात्सिद्धम् ॥ * ॥

(भाष्यम्) **समानाधिकरणत्वाद्विशेषणानां युक्तवद्भावो भविष्यति॥**

(उद्द्योतः) समानाधिकरणत्वादिति । अर्थस्य युक्तवद्भावे तदर्थामित्ते अनियतलिङ्गसंख्ये सर्वत्र सिद्धमिति तात्पर्यम् ॥

(प्रत्याख्यानभाष्यम्)

यद्येवं, नार्थोऽनेन । लुपोन्यत्रापि जातेर्युक्तवद्भावो न भवति ॥ क्वान्यत्र ?॥ बदरी सूक्ष्मकण्टका मधुरा [वृक्ष] इति ॥

(प्रदीपः) **बदरी सूक्ष्मकण्टकेति** । मधुरादीनां विशेषणानां बदर्युपनिपाते तल्लिङ्गसंख्यायोगः ॥ वृक्षोपनिपाते तु वृक्षाश्रयलिङ्गसंख्यायोगः ॥

(उद्द्योतः) अन्यत्रापि जातेर्युक्तवद्भावो नेति ॥ विशेष्यलिङ्गादिग्राहिता नेत्यर्थः ॥ वृक्षोपनिपाते त्विति । बदरी वृक्षो मधुर इति यथा । एवं प्रकृतेपि रूपद्वये सिद्धे व्यर्थं सूत्रमिति भावः ॥

(आक्षेपभाष्यम्)

किं पुनः कारणमन्यत्रापि जातेर्युक्तवद्भावो न भवति ? ॥

(उद्द्योतः) पृच्छति—किं पुनरिति ॥

(समाधानभाष्यम्)

आविष्टलिङ्गा जातिर्यल्लिङ्गमुपादाय प्रवर्तते, उत्पत्तिप्रभृत्या विनाशान्न तद् लिङ्गं जहाति ॥

(प्रदीपः) **आविष्टलिङ्गेति** । आविष्टं लिङ्गं यया साऽऽविष्टलिङ्गा नियतलिङ्गेत्यर्थः । सर्वत्र सर्वेषां लिङ्गानां सद्भावेपि केनचिच्छब्देन किंचिल्लिङ्गं प्रत्याय्यत इति शब्दविशेषापेक्षयाविष्टलिङ्गत्वमुच्यते ॥ **उत्पत्तिप्रभृत्या विनाशादिति** । जातेरुत्पत्तिविनाशायोगात् शब्दव्यवहारगतावुत्पत्तिविनाशौ गृह्येते । तेनासंसारं यावच्छब्दो व्यवहारस्तावज्जातेर्नियतलिङ्गत्वमित्यर्थः ॥

(उद्द्योतः) उत्तरयति—आविष्टेति ॥ ननु जातेर्लिङ्गाभावत्वाल्लिङ्गाविष्टा जातिरिति वक्तव्ये विपरीतोच्चारणमयुक्तमत आह—**आविष्टमिति** । विशिष्य गृहीतमित्यर्थः ॥ एवं व्युत्पत्तौ जातेर्नियतलिङ्गोपादानत्वेन तत्त्वं प्रतीयत इत्याह—**नियतेति** । यद्यपि जातिशब्दा अनियतलिङ्गा अपि दृश्यन्ते तथापि प्रकृताभिप्रायमेतत् ॥ ननु सर्वत्र सर्वलिङ्गसत्त्वात्कथं नियतलिङ्गत्वमत आह—**सर्वत्रेति** ॥ **शब्दव्यवहारगताविति** । व्यक्तिगतेति नोक्तं, व्यक्तेरपि कस्याश्चिन्नित्यत्वात् । अत एव शब्दगतेति नोक्तम् । जातिरित्युपलक्षणं नियतलिङ्गशब्दमात्रार्थस्य ॥

(तटस्थाक्षेपभाष्यम्)

न तर्हीदानीमयं योगो वक्तव्यः ॥

(सिद्धान्तिसमाधानभाष्यम्)

वक्तव्यश्च । किं प्रयोजनम् ? ॥ इदं तत्र तत्रोच्यते—गुणवचनानां शब्दानामाश्रयतो लिङ्गवचनानि भवन्तीति, तदनेन क्रियते ॥

(प्रदीपः) **गुणवचनानामिति** । पदसंस्कारपक्षे वाचनिकमेतत् । पदे हि पदान्तरनिरपेक्षे संस्क्रियमाणे नपुंसकं लिङ्गसर्वनामप्राप्तमेकत्वं च वस्त्वन्तरनिरपेक्षत्वात्सन्निहितमिति शुक्लं पटा इति प्राप्ते भाविनो बहिरङ्गस्याश्रयस्य सम्बन्धिन्यौ लिङ्गसंख्ये अनेन प्रतिपाद्येते । **'विशेषणानां'** गुणवचनानामित्यर्थः । **युक्तवद्व्यक्तिवचने** । आश्रयवल्लिङ्गसंख्ये इत्यर्थः ॥ यदा तु वाक्यसंस्कारस्तदायमनुवाद एव । आश्रयविशेषस्य पूर्वमेव प्रक्रमे विशेषणानामपि तन्निष्ठत्वात् । तद्गतयोर्लिङ्गसंख्ययोः सिद्धत्वात् । यदा तु जातिर्विशेषणं तदा न भवति युक्तवद्भावः ॥

(उद्द्योतः) भाविन इति । भाविबुद्धिविषयस्येत्यर्थः ॥ **गुणवचनानामिति** । जातिक्रियादिभिन्नानामित्यर्थः ॥ तेन शक्यं च श्वमांसादिभिरपि क्षुदुपहन्तुमित्याद्युपपन्नम्, गुणाभेदेन गुणोपसर्जनगुणिबोधकानामाश्रयत आश्रयविशेषतो लिङ्गादिकमित्यर्थः ॥ अयं भाष्यकृत्कृतः सूत्रार्थः ॥ तन्निष्ठत्वादिति तन्निष्ठत्वेन ग्रहादित्यर्थः ॥ यदा तु जातिरिति । यथा बदरी वृक्ष इत्यादाविति भावः ॥

(७११ नियमवार्तिकम् ॥ ३ ॥)

॥ * ॥ हरीतक्यादिषु व्यक्तिः ॥ * ॥

(भाष्यम्) **हरीतक्यादिषु व्यक्तिर्भवति युक्तवद्भावेन । हरीतक्याः फलानि हरीतक्यः फलानि ।**

(प्रदीपः) **हरीतक्यादिष्विति** । नियमार्थमेतत् । तेन वचनमभिधेयाश्रयं भवति ॥

(७१२ नियमवार्तिकम् ॥ ४ ॥)

॥ * ॥ खलतिकादिषु वचनम् ॥ * ॥

(भाष्यम्) **खलतिकादिषु वचनं भवति युक्तवद्भावेन । खलतिकस्य पर्वतस्यादूरभवानि वनानि खलतिकं वनानि ।**

(प्रदीपः) **खलतिकमिति** । खलतिको नाम पर्वतस्तस्यादूरभवानि वनानीति लिङ्गमभिधेयाश्रयमेव भवति ॥

(७१३ आक्षेपवार्तिकम् ॥ ५ ॥)

॥ * ॥ मनुष्यलुपि प्रतिषेधः ॥ * ॥

(भाष्यम्) **मनुष्यलुपि प्रतिषेधो वक्तव्यः ॥ चञ्चा अभिरूपः । वध्रिका दर्शनीयः ॥ विशेषणानां चाजातेः ॥ ५१ ॥**

(प्रदीपः) **मनुष्यलुपीति** । विशेषणानामयं प्रतिषेधः । तेन चञ्चाभिरूप इत्यभिधेयाश्रये लिङ्गसंख्ये भवतः । तृणमयः पुरुषश्चञ्चा तत्सदृशो मनुष्यश्चञ्चा । **संज्ञायामिति** विहितस्य कनो लुम्मनुष्य इति लुप् ॥ ५१ ॥

(उद्द्योतः) मनुष्यलुपीत्यस्य युक्तवद्भावप्रतिषेधस्य यथेत्यसंगतमित्यत आह—विशेषणानामिति ॥ लुपन्तस्य तु

भवत्येवेति भावः ॥ अभिधेयाश्रये इति । विशेष्यगतं यद् युक्तवद्भावेन लिङ्गं विशेषणे प्राप्तं तस्यायमुपस्थितत्वाद् निषेध इति विशेष्यभूतार्थगतं पुल्लिङ्गमत्र भवतीति भावः ॥ एतेन मनुष्यलुपी-त्यनेन विशेषणानां विशेष्यगतलिङ्गादिनिषेध इत्यभिरूप इत्यत्र भाष्यकारवचनादेव पुंस्त्वमिति बोध्यमित्यपास्तम् ॥ ५२ ॥

(१०५ युक्तवद्भावप्रत्याख्यानसूत्रम् ॥ १।२।२ आ. ९ सू.)

१२७ तदशिष्यं संज्ञाप्रमाणत्वात् ॥ १ । २ । ५३ ॥

(उद्द्योतः) तदशिष्यं ॥५३॥ तत् । युक्तवद्भावशास्त्रम् ॥

(संज्ञाशब्दार्थनिर्णयाधिकरणम्)

(आक्षेपभाष्यम्)

किं या एताः कृत्रिमाष्टिघुभादिसंज्ञास्तत्प्रामाण्यादशिष्यम् ? ॥

(प्रदीपः) **तदशिष्यम् ॥ ५३ ॥ किं या एता इति** । प्रत्यासत्तिन्यायाश्रयेण प्रश्नः ॥

(उद्द्योतः) भाष्ये—**कृत्रिमा इति** । शास्त्रतो बोधितसंकेता इत्यर्थः ॥ कृत्रिमसंज्ञाग्रहणे हेतुमाह—**प्रत्यासत्तीति** ॥

(समाधानभाष्यम्)

नेत्याह । संज्ञानं संज्ञा । तदशिष्यम् ॥ ५३ ॥

(प्रदीपः) **नेत्याहेति** । प्रत्यासत्तेः सामर्थ्यं बलवत् । नहि टिघुभादिसंज्ञानां प्रमाणत्वं युक्तवद्भावशास्त्रस्याशिष्यत्वे हेतुरुपपद्यते सम्बन्धाभावात् ॥ **संज्ञानमिति** । अवगमः सम्प्रत्यय इत्यर्थः । तत्र यथापो दाराः सिकता वर्षा इत्युक्ते लिङ्गसंख्याविशेषावगतिरुत्पद्यमाना प्रमाणम् । एवं पञ्चाला वरणा इत्यादावपि । न च पञ्चालादयो यौगिका, अपि तु जनपदादीनां संज्ञास्ततो योगानवगमात् तद्धितो नोत्पद्यते इति लुबपि न वक्तव्यः । तत्र सर्वेषां लिङ्गानां सर्वत्र भावात् केनचिच्छब्देन प्रत्याय्यमानं वस्तु कस्यचिल्लिङ्गस्य व्यञ्जकमिति दारादिषु नियतलिङ्गता सिद्धा । बहुत्वमप्यवयवगतं शक्तिगतं चान्यत्र समारोप्यत इति संख्यायोगोपि सिद्धः । **एका सिकते**त्याद्यपि शिष्टप्रयोगदर्शनात् सिध्यति ॥ ५३ ॥

(उद्द्योतः) **सामर्थ्यमिति** । प्रकरणाल्लिङ्गं बलवदित्यर्थः ॥ **अवगम इति** । भावेऽबन्तो यौगिकः संज्ञाशब्द इत्यर्थः ॥ प्रतीतिप्रामाण्यमवश्याश्रयणीयमित्याह—**तत्र यथेति** ॥ **प्रमाणमिति**। वचनमन्तरेणापीत्यर्थः ॥ "**लुब्योगाप्रख्यानात्**" "**योगप्रमाणे च तदभावेऽदर्शनं स्यात्**" इत्यनयोस्तात्पर्यं दृष्टान्तदार्ष्टान्तिकयो रूढयौगिकत्वरूपवैषम्यपरिहारं चाह—**न चेति** । एवं च लिङ्गप्रकरणं **जात्याख्याया**मित्यादि संख्याप्रकरणं च पूर्वाचार्यानुरोधेन कृतमिति ध्वनितं सूत्रकृता । सर्वं चेदं **कालोपसर्जने चेति** चेन संगृहीतम् ॥ **योगानवगमादिति** । संप्रति विनापि क्षत्रिययोगं जनपदे पञ्चालशब्दव्यवहारदर्शनादित्यर्थः ॥ **तत्र सर्वेषामिति** । उपचयापचयादिरूपस्य तस्य केवलान्वयित्वादिति भावः ॥ **वस्तु द्रव्यम्** ॥ लिङ्गसंख्याकारकाश्रयत्वं हि द्रव्यत्वमिति तदेव द्रव्यत्वानुपपत्तिपरिहाराय लिङ्गव्यञ्जकं, शब्दस्तु करणमिति भावः ॥ एवं च दारपदार्थस्य स्त्रीत्वेपि शब्देनोपचयलक्षणं पुंरूपमेव व्यज्यते । सर्वेषां सर्वत्र सत्त्वादिति तात्पर्यम् ॥ **एका सिकतेति** । अयं प्रयोगो हयवरट्सूत्रे भाष्ये । एवमन्येपि अवादिशब्दविपर्येपि शिष्टप्रयुक्ताः साधव इति ध्वनयन्नाह—**आदीति** ॥ ५३ ॥

(१०६ बहुत्वातिदेशसूत्रम् ॥ १ । २ । २ आ. १० सू.)

१३२ जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम् ॥ ५८ ॥

(एकत्वेबहुवचनसाधनाधिकरणम्)

(आक्षेपभाष्यम्)

इदमयुक्तं वर्तते ॥ किमत्रायुक्तम् ? ॥ बहवस्त्वेर्थास्तत्र युक्तं बहुवचनम् । तद्यदेकवचने शासितव्ये बहुवचनं शिष्यते एतदयुक्तम् । बहुष्वेकवचनमिति नाम वक्तव्यम् ॥

(प्रदीपः) **जात्या ॥ ५८ ॥** जातिरुपलक्षणम् । द्रव्यं तु शब्दार्थ इति दर्शनाश्रयेणाह—**इदमयुक्तमिति** ॥ **बहुष्वेकवचनमिति** । अत्र पक्षे जातेरुपलक्षणत्वेनाख्या जात्याख्येति व्याख्यानम् ॥

(उद्द्योतः) **जात्याख्यायाम् ॥ ५८ ॥** जातिवादिनो मते जातेरेकत्वाद् बहुवचनार्थमावश्यकमितीदमयुक्तमित्यसङ्गतमत आह—**द्रव्यं त्विति** । जातेरुपलक्षणत्वं तु शक्यतावच्छेदकतया बोध्यम् । प्रकारान्तरमपि मञ्जूषायां द्रष्टव्यम् ॥ जात्याख्यायां बहुष्वेकवचनमित्यसङ्गतमत आह—**अत्र पक्ष इति** । क्रियादिप्रवृत्तिनिमित्तकाश्च तद्व्यावर्त्या इति भावः ॥

(समाधानभाष्यम्)

अत उत्तरं पठति—

(७१४ समाधानवार्तिकम् ॥ १ ॥)

॥ * ॥ जात्याख्यायां सामान्याभिधानादैकार्थ्यम् ॥ * ॥

(भाष्यम्) **जात्याख्यायां सामान्याभिधानादैकार्थ्यं भविष्यति । यत्तद् व्रीहौ व्रीहित्वम् यवे यवत्वम् गार्ग्ये गार्ग्यत्वम् तदेकम्, तच्च विवक्षितम्, तस्यैकत्वादेकवचनमेव प्राप्नोति । इष्यते च बहुवचनं स्यादिति । तद्यान्तरेण यत्नं न सिध्य-**

तीति जात्याख्यायामेकस्मिन् बहुवचनम् । एवमर्थमिदमुच्यते ॥

(प्रदीपः) जातिपदार्थपक्षाश्रयेणोत्तरमाह—**जात्याख्यायामिति** ॥ **गार्ग्ये गार्ग्यत्वमिति** । गोत्रस्यापि जातित्वाभ्युपगमादेतदुक्तम् । बहुषु गर्गेषु गार्ग्यत्वस्याभिन्नस्याभावात् ॥ एकस्मिंस्तु पिण्डे अवस्थाभेदानुगता डित्थत्वादिका जातिर्जात्याख्यायामिति वचनसामर्थ्यान्न गृह्यते । जातिपदार्थवादिमते हि सर्वे शब्दा जात्यार्थाभिधायिन इति सामर्थ्याद्भिन्नपिण्डविषया जातिराश्रीयते ॥

(उद्योतः) द्रव्यवादे उत्तरासङ्गतेराह—**जातिपदार्थेति** ॥ जात्याख्यायामेकस्मिन्निति यदैकार्थ्यं तद्युक्तं सामान्याभिधानादिति योजना वार्तिकस्य ॥ अत्र पक्षे वाहदोहाद्यन्वयो विशेषणीभूतव्यक्तिद्वारकपरम्परया जातावेवेति भावः ॥ अभ्युपगमत्वे हेतुमाह—**बहुष्विति** ॥ **अभिन्नस्याभावा**दिति पाठः । अत एवाभ्युपगमवादोयमिति तात्पर्यम् ॥ कचित्त्व**भिन्नस्य भावा**दिति पाठः । तदा जात्यङ्गीकारे प्रमाणदर्शनमिदम्, अन्यथा गर्गनिष्ठजनकतानिरूपितजन्यत्वस्य प्रतिव्यक्तिभेदाद् गार्ग्य इत्यनुगताकारप्रतीतिर्न स्यादिति भावः ॥ नन्वेवं परिमाणभेदाद्द्रव्यभेदेन डित्थत्वादीनामपि जातिशब्दत्वेन तत्रापि बहुवचनं स्यादत आह—**एकस्मिन्निति** ॥ सामर्थ्यमेव दर्शयति—**जातिपदार्थेति** ॥ **सर्वे शब्दा इति** । उक्तयुक्त्या पाचकादयोपि ॥ भाष्ये—**तच विवक्षितमिति** । प्राधान्येनेति शेषः ॥

(काकुभाष्यम्)

अस्ति प्रयोजनमेतत् । किं तर्हीति ।

(७१५ आक्षेपवार्तिकम् ॥ २ ॥)

॥ * ॥ तत्रैकवचनादेशो उक्तम् ॥ * ॥

(भाष्यम्) किमुक्तम्? ॥ व्रीहिभ्य आगत इत्यत्र "घेर्ङिति" इति गुणः प्राप्नोतीति ॥

(उद्योतः) भाष्ये **व्रीहिभ्य इति** । सूत्रे एकस्मिन्नित्येकशब्देनैकवचनं गृह्यते भीमो भीमसेन इतिवत् ॥ सप्तमी च षष्ठ्यर्थे इति भावः ॥

(समाधानभाष्यम्)

नैष दोषः ।

(७१६ समाधानवार्तिकम् ॥ ६ ॥)

॥ * ॥ अर्थातिदेशात्सिद्धम् ॥ * ॥

(भाष्यम्) अर्थातिदेशोयम् । नेदं पारिभाषिकस्य वचनस्य ग्रहणम् ॥ किं तर्हि ? ॥ अन्वर्थग्रहणम्—उच्यते वचनम् । बहूनामर्थानां वचनं बहुवचनमिति । यावद् ब्रूयादेकोर्थो बहुवद्भवतीति तावदेकस्मिन् बहुवचनमिति ॥

(प्रदीपः) **बहूनामिति** । बहूनामर्थानां बहुत्वमेवोच्यते इत्येकस्मिन्नर्थे बहुत्वमनेनातिदिश्यत इति बहुत्वाद्बहुवचनं भवतीति नास्ति स्थान्यादेशभावः । एवं **तिष्यपुनर्वस्वोरि**त्यत्रापि द्विवचनबहुवचनशब्दाभ्यां द्वित्वबहुत्वयोरभिधानादर्थातिदेशात्स्थान्यादेशभावाभावः ॥

(उद्योतः) सप्तम्युपादानादतिदेश एवेत्युत्तरम् ॥ बहूनामर्थानां वचनं भ्यसादिबहुवचनमपि भवतीत्यत आह—**बहूनामिति** । कर्मणि ल्युट् । बहूनामर्थानां संबन्धि यदुच्यते तद्बहुवचनम् । तच्चोपस्थितत्वाद्बहुत्वमेव तदाह—**बहुत्वमेवोच्यत इति** । एकत्वरूपेर्थे शास्त्रीयो बहुत्वरूपार्थस्य तादात्म्येनाहार्यारोप इति तात्पर्यम् ॥ अत एव तद्विशेषणानामपि सिध्यति ॥ **एवमिति** । अन्यथा तत्रापि तिष्यपुनर्वसू इत्यत्र **जसि चेति** गुणः स्यादिति भावः ॥

(७१७ प्रतिषेधाक्षेपवार्तिकम् ॥ ४ ॥)

॥ * ॥ संख्याप्रयोगे प्रतिषेधः ॥ * ॥

(भाष्यम्) संख्याप्रयोगे प्रतिषेधो वक्तव्यः । एको व्रीहिः संपन्नः सुभिक्षं करोति । एको यवः संपन्नः सुभिक्षं करोति ॥

(प्रदीपः) **संख्याप्रयोग इति** । एकस्यैव बहुत्वातिदेशः क्रियमाण एकशब्दप्रयोगेपि प्राप्नोतीति प्रतिषेध उच्यते ॥

(उद्योतः) एकशब्दप्रयोगविरोधाद् बहुवचनाप्राप्तेराह—**एकस्यैवेति** । जातेरेकत्वावगतावेवातिदेशप्रवृत्तेरिति भावः ॥

(७१८ प्रतिषेधवार्तिकम् ॥ ५ ॥)

॥ * ॥ अस्मदो नामयुवप्रत्यययोश्च ॥ * ॥

(भाष्यम्) अस्मदो नामप्रयोगे युवप्रत्ययप्रयोगे च प्रतिषेधो वक्तव्यः । नामप्रयोगे,—अहं देवदत्तो ब्रवीमि । अहं यज्ञदत्तो ब्रवीमि ॥ युवप्रत्ययप्रयोगे—अहं गार्ग्यायणो ब्रवीमि । अहं वात्स्यायनो ब्रवीमि ॥

(वार्तिकेयुवग्रहणवैयर्थ्यभाष्यम्)

युवग्रहणेन नार्थः—"अस्मदो नामप्रत्ययप्रयोगे न" इत्येव । इदमपि सिद्धं भवति—अहं गार्ग्यो ब्रवीमि । अहं वात्स्यो ब्रवीमि ॥

(उद्योतः) भाष्ये प्रसङ्गादस्मदो द्वयोश्चेत्यस्य प्रतिषेधमाह—**अस्मदो नाम्नेति** ॥

(भाष्यम्) अपर आह—

"* अस्मदः सविशेषणस्य प्रयोगे न *" इत्येव । इदमपि सिद्धं भवति—अहं पटुर्ब्रवीमि । अहं पण्डितो ब्रवीमि ॥

(७१९ प्रत्याख्यानवार्तिकम् ॥ ६ ॥)

॥ * ॥ अशिष्यं वा बहुवत् पृथक्त्वाभिधानात् ॥ * ॥

(भाष्यम्) अशिष्यो वा बहुवद्भावः ॥ किं कारणम्?॥ पृथक्त्वाभिधानात्। पृथक्त्वेन हि द्रव्याण्यभिधीयन्ते। बहुवस्तेऽर्थास्तत्र युक्तं बहुवचनम्॥

(प्रदीपः) उभयपदार्थपक्षाश्रयेण प्रत्याख्यातुमाह—अशिष्यमिति ॥

(उद्द्योतः) ननु द्रव्यपदार्थाश्रयेण प्रत्याख्याने 'व्रीहिः सम्पन्न' इति प्रयोगो न स्यादत आह—उभयेति। कदाचिद्द्रव्यं प्रधानं कदाचिज्जातिः प्रधानमित्यर्थः ॥ भाष्ये पृथक्त्वेनेति। भेदेनेत्यर्थः ॥

(आक्षेपभाष्यम्)

किमुच्यते—पृथक्त्वाभिधानादिति। यावता इदानीमेवोक्तम्—*जात्याख्यायां सामान्याभिधानादैकार्थ्यम्* इति?॥

(७२० प्रत्याख्यानहेतुवार्तिकम् ॥ ७ ॥)

॥ * ॥ जातिशब्देन हि द्रव्याभिधानम् ॥ * ॥

(भाष्यम्) जातिशब्देन हि द्रव्यमप्यभिधीयते जातिरपि॥

(प्रदीपः) तत्र कदाचिज्जातेः प्राधान्यं कदाचिद् द्रव्यस्येति यथेष्टप्रयोग उपपद्यते ॥ ५८ ॥

(उद्द्योतः) भाष्ये—जातिशब्देनेति। जातिशब्दत्वाभिमतेनेत्यर्थः। निष्कृष्टजात्यभिधायकगोत्वादिशब्दे तु नायं विधिरिष्ट इति भावः ॥ तदाह—द्रव्यमपीति। प्राधान्येनेति शेषः। तदाह—तत्र कदाचिदिति। जातिप्रकारकव्यक्तिविशेष्यक एव शक्तिग्रहः 'गौर्गोपदवाच्य' इति जातिव्यक्त्युभयविषयकबोधे कारणम्। अत एव जातिविशेष्यकशक्तिग्रहविषयाद् गोत्वपदाच्च कदापि व्यक्तिबोधः॥ जातिव्यक्त्योरन्यतरस्य विशेष्यतायां च पुरुषेच्छैव नियामिका। तात्पर्यग्राहकं चैकवचनबहुवचनादि ॥ एतदेवाभिप्रेत्य जातिप्राधान्ये द्वन्द्वे एकवद्भावो व्यक्तिप्राधान्ये तु नेति व्यवहार इति भावः॥ तत्र जातौ व्यक्तेः प्रकारताऽभेदेनेति न वाह्याद्यन्वयानुपपत्तिः। गोत्वपदजन्यगोत्वबोधे तु भेदेनेति न गोत्वं वाह्येत्यादिप्रयोगः। व्यक्तिद्वारकोऽन्वय इत्यस्याप्ययमेवार्थ इति बोध्यम्॥

(आक्षेपभाष्यम्)

कथं पुनर्ज्ञायते जातिशब्देन द्रव्यमप्यभिधीयत इति?॥

(समाधानभाष्यम्)

एवं हि कश्चिन्महति गोमण्डले गोपालकमासीनं पृच्छति—अस्त्यत्र कांचिद्गां पश्यसीति। स पश्यति—'पश्यति चायं गाः, पृच्छति च—'कांचिदत्र गां पश्यसि' इति, नूनमस्य द्रव्यं विवक्षितम्—'इति॥ तद्यदा द्रव्याभिधानं तदा बहुवचनं भविष्यति। यदा सामान्याभिधानं तदैकवचनं भविष्यति॥ जात्याख्यायाम्॥ ५८॥

(उद्द्योतः) भाष्ये—महति गोमण्डल इति। अतिनिविडगोमण्डलेऽविविक्ततया दृष्टे इत्थमुक्तिः। तत्र जातेरेव शब्दार्थत्वे जातेर्दृष्टत्वात् प्रश्नानुपपत्तिरित्यर्थः॥ ५८॥

(१०७ बहुत्वातिदेशसूत्रम् ॥ १।२।२। आ. ११ सू.)

१३३ अस्मदो द्वयोश्च ॥ १।२।५९॥

(प्रत्याख्यानभाष्यम्)

अयमपि योगः शक्योऽवक्तुम्॥

(आक्षेपभाष्यम्)

कथम्—अहं ब्रवीमि आवां ब्रूवः वयं ब्रूमः?॥

(समाधानभाष्यम्)

इमानीन्द्रियाणि कदाचित्स्वातन्त्र्येण विवक्षितानि भवन्ति। तद्यथा—इदं मे अक्षि सुष्ठु पश्यति, अयं मे कर्णः सुष्ठु शृणोतीति। कदाचित्पारतन्त्र्येण विवक्षितानि भवन्ति—अनेनाक्ष्णा सुष्ठु पश्यामि, अनेन कर्णेन सुष्ठु शृणोमीति। तद्यदा स्वातन्त्र्येण विवक्षा तदा बहुवचनं भविष्यति। यदा पारतन्त्र्येण तदैकवचनद्विवचने भविष्यतः॥ अस्मदो॥ ५९॥

(प्रदीपः) अस्मदः॥५९॥ तद्यदेति। एकेन्द्रियप्रवृत्तौ चेतरेन्द्रियान्तराणामौदासीन्येन संविधातृत्वात् कर्तृत्वविवक्षेति वयं पश्याम इत्यादि सिद्धम्। शरीर इवेन्द्रियेष्वप्यहंकारोत्पादाद्वयमित्यनेनेन्द्रियाणामभिधानात्॥ पारतन्त्र्यविवक्षायां लिन्द्रियाणामहं ब्रवीमि इत्येकवचनं सिद्धम्। युष्मदस्मदोश्चैकशेषेऽस्मदोर्थद्वयाभिधानाद्द्विवचनमिति नार्थो योगेन। संप्रत्ययप्रामाण्याच्च युष्मदि गुरौ पक्षे बहुवचनं सिद्धम्॥ ५९॥

(उद्द्योतः) अस्मदो द्व॥ ५९॥ नन्विन्द्रियाणां स्वातन्त्र्येपि एकेन्द्रियसाध्यक्रियायामिन्द्रियान्तराणां कर्तृत्वाभावाद्बहुवचनमनुपपन्नमत आह—एकेन्द्रियेति। स्वविषयौदासीन्यं संविधातृत्वे हेतुः। संविधातृत्वं, सहकारित्वम्॥ नन्वेवमस्मदः प्रयोगोनुपपन्नोत आह—शरीर इवेति। अहंकारः। अहंत्वप्रतीतिरहं काण इत्यादिः॥ पारतन्त्र्येति। तथा च करणत्वेन विवक्षितत्वात्संविधातृत्वलक्षणकर्तृत्वं नास्तीत्यर्थः॥ उच्चारयित्रात्मन अहंकारास्पदात्मनो वा एकत्वादावामित्यनुपपन्नमत आह—एकशेषेति। त्यदादीनां यत्परं तच्छिष्यत इति भावः॥ अस्मदोर्थद्वयाभिधानादित्यत्रास्मद इति शेषत्वविवक्षया षष्ठी॥ संप्रत्य-

येति । व्यवहारेत्यर्थः ॥ एवं च युष्मदि गुरावेकेषामिति क्वचिद्वृत्तावुच्यमानमसङ्गतमिति भावः । अत एवाचार्याः कथयन्तीत्यादि संगच्छते । इत्थमेव डित्थाः कथयन्तीत्याद्युपपत्तिर्बोध्या । एतदर्थं च प्रत्याख्यानप्रकारस्यावश्यकत्वात्सूत्रं प्रत्याख्यातमिति भावः ॥५९

(१०८ बहुत्वातिदेशसूत्रम् ॥ १ । २ ।२ आ. १२ सू.)

१३४ फल्गुनीप्रोष्ठपदानां च नक्षत्रे ॥ १ । २ । ६० ॥

(प्रत्याख्यानभाष्यम्)

अयमपि योगः शक्योऽवक्तुम् ॥

(आक्षेपभाष्यम्)

कथम्—उदिते पूर्वे फल्गुन्यौ, उदिताः पूर्वाः फल्गुन्यः, उदिते पूर्वे प्रोष्ठपदे, उदिताः पूर्वाः प्रोष्ठपदाः ? ॥

(समाधानभाष्यम्)

फल्गुनीसमीपगते चन्द्रमसि फल्गुनीशब्दो वर्तते । बह्वस्तेर्थास्तत्र युक्तं बहुवचनम् । यदा तयोरेवाभिधानं तदा द्विवचनं भविष्यति ॥ फल्गुनी ॥ ६० ॥

(प्रदीपः) फल्गुनी ॥६०॥ बह्वस्तेर्था इति । अमावास्यायामप्यादित्यमण्डलं प्रविष्टेन चन्द्रेण नक्षत्राणां योगोस्त्येवेति तदापि बहुवचनमर्धर्चाः छत्रिण इत्यादिन्यायेन सिद्धम् । एकस्यां तु तारायां फल्गुनीशब्दो न वर्तत इति एकवचनाभावः । सर्वत्र लौकिकः प्रयोगः प्रामाण्येनाश्रीयते इत्यनवस्था न भवति ॥ ६० ॥

(उद्योतः) फल्गुनी ॥ ६० ॥ अमायां चन्द्रस्य नष्टत्वात्कथं बहुवचनमित्यत आह—अमेति ॥ ननु चन्द्रस्य फल्गुन्यादिपदवाच्यत्वाभावात् कथं तमादाय फल्गुन्य इत्यादिप्रयोगोत आह—अर्धर्चा इति । तद्रूपारोपात्तच्छब्दप्रवृत्तिरिति भावः ॥ नन्वेवमेकर्क्षविवक्षायामेकवचनमपि स्यादत आह—एकस्यामिति । नन्वेवं नक्षत्रान्तरेपि चन्द्रसंबन्धविवक्षायां द्विवचनादि स्यादत आह—सर्वत्रेति । अनवस्था अतिप्रसङ्गः ॥ ६० ॥

(१०९–११० एकत्वातिदेशसूत्रे ॥१।२।२आ०१३।१४ सू०)

१३५ छन्दसि पुनर्वस्वोरेकवचनम् ॥ १ । २ । ६१ ॥

१३६ विशाखयोश्च ॥ १ । २ । ६२ ॥

(प्रत्याख्यानभाष्यम्)

इमावपि योगौ शक्याववक्तुम् ॥

(आक्षेपभाष्यम्)

कथम् ? ।

(७२२ प्रत्याख्यानहेतुवार्तिकम् ॥ १ ॥)

॥ * ॥ पुनर्वसुविशाखयोः सुपां सुलुक्पूर्वसवर्णेति सिद्धम् ॥ * ॥

(भाष्यम्) पुनर्वसुविशाखयोः "सुपां सुलुक्पूर्वसवर्ण" इत्येव सिद्धम् ॥ छन्दसि ॥ ॥ विशाखयोः ॥ ६२ ॥

(१११ द्वित्वातिदेशसूत्रम् ॥ १ । २ । २ आ० १५ सू०)

१३७ तिष्यपुनर्वस्वोर्नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनं नित्यम् ॥ १।२।६३ ॥

(आक्षेपभाष्यम्)

तिष्यपुनर्वस्वोरिति किमर्थम् ? ॥

(समाधानभाष्यम्)

कृत्तिकारोहिण्यः ॥

(आक्षेपभाष्यम्)

नक्षत्र इति किमर्थम् ? ।

(प्रदीपः) तिष्य ॥६३॥ नक्षत्र इति किमर्थमिति । तिष्यपुनर्वसवो माणवका इत्यत्र गौणार्थत्वान्न भविष्यतीति प्रश्नः ॥

(उद्योतः) तिष्यपुन ॥ ६३ ॥ ननु माणवकवाचिद्वन्द्वनिवृत्त्यर्थं तदत आह—तिष्येति ॥

(समाधानभाष्यम्)

तिष्यश्च माणवकः, पुनर्वसू च माणवकौ, तिष्यपुनर्वसवः ॥

(प्रदीपः) उत्तरवादिनस्त्वयमभिप्रायः तिष्येण युक्तकालस्तिष्यस्तिष्ये जातो माणवक इति यौगिकत्वान्नास्ति गौणार्थत्वम् ॥

(उद्योतः) तिष्येणेति । नक्षत्रेण युक्तः काल इत्यणो लुबविशेष इति लुपि जाते सन्धिवेलाद्यणः स्वातितिष्यपुनर्वस्विति लुक् ॥ यौगिकत्वादिति । लोपेनाप्यवशिष्टस्य तदर्थान्तर्भावेण शक्तिरेव बोध्यते । अत एव लुबादिप्रत्याख्यानं सूत्रकृतोक्तमिति भावः ॥

(आक्षेपभाष्यम्)

अथ नक्षत्र इति वर्तमाने पुनर्नक्षत्रग्रहणं किमर्थम् ? ।

(समाधानभाष्यम्)

अयं तिष्यपुनर्वसुशब्दोऽस्त्येव ज्योतिषि वर्तते । अस्ति च कालवाची । तद्यथा-बह्वस्तिष्यपुनर्वसवोतिक्रान्ताः, कतरेण तिष्येण गत इति । तयो ज्योतिषि वर्तने तस्येदं ग्रहणम् ॥

(प्रदीपः) ज्योतिषि वर्तेत इति । नन्वेकेनैव नक्षत्रग्रहणेन कालमाणवकयोर्निवृत्तिः सिद्धा तत्र किं द्वितीयेन नक्षत्रग्रहणेन ॥ नैतदस्ति । अन्तरङ्गः कालः वहिरङ्गस्तु माणवक इत्यन्तरङ्गस्यैव कालस्यैकेन नक्षत्रग्रहणेन निवृत्तिः स्यात् । यथाऽकर्मकश्रुत्यान्तरङ्गं द्रव्यकर्म निषिध्यते न कालकर्मेति मासमास्यते देवदत्तेनेत्यत्रापि भावे लकारः सिद्धो भवति । द्वितीयेन तु नक्षत्रग्रहणेन वहिरङ्गोऽपि माणवको निवर्त्यते ॥

(उद्द्योतः) अन्तरङ्ग इति । कालार्थतद्धितान्तान्माणवकार्थतद्धितोत्पत्तिरिति कालमाणवकयोरन्तरङ्गबहिरङ्गतेति भावः ॥ यथेति । द्रव्यकर्मणा क्रियास्वरूपपरिपूरणं कालकर्मणा त्ववगतायाः क्रियायाः कालसंबन्धपूरणमिति तयोरन्तरङ्गबहिरङ्गता बोध्या ॥

(समाधानान्तरभाष्यम्)

अथ वा नक्षत्र इति वर्तमाने पुनर्नक्षत्रग्रहणस्यैतत्प्रयोजनम्—विदेशस्थमपि तिष्यपुनर्वस्वोः कार्यं [तदपि] नक्षत्रस्यैव यथा स्यात्। *तिष्यपुष्ययोर्नक्षत्राणि यलोपो वक्तव्यः* इति नक्षत्रग्रहणं न कर्तव्यं भवति ॥

(प्रदीपः) ननु नक्षत्रद्वन्द्वे इत्युक्ते अर्थाद्द्वयोरपि कालमाणवकयोर्निवृत्तिः सिद्धैवेत्याह—अथ वेति ॥ तिष्यपुनर्वस्वोरिति योगविभागः क्रियते नक्षत्र इति चानुवर्तते । तेन यत्किंचित्तिष्यपुनर्वस्वोः कार्यं तन्नक्षत्रवृत्त्योरेव भवतीत्यर्थः ॥

(उद्द्योतः) नन्विति । अकर्मकग्रहणेन श्रुत्यैव साक्षात्कर्मणि व्यावर्त्यमाने युक्ता पूर्वपश्चात्संबन्धसत्त्वेनान्तरङ्गस्यैव व्यावृत्तिर्नैत्येवं प्रकृते । अस्य हि स्वार्थसमर्पणद्वारान्यव्यावर्तकत्वेनाविशेषादुभयव्यावर्तकत्वसंभवादिति भावः ॥ अत्रत्यस्याङ्गाधिकारस्थेन कथं संबन्धोत आह—तिष्येति । नक्षत्रस्याण् नक्षत्राण् ततः सप्तम्यां नक्षत्राणीति निर्देशः ॥

(समाधानान्तरभाष्यम्)

अथ वा नक्षत्र इति वर्तमाने पुनर्नक्षत्रग्रहणस्यैतत्प्रयोजनं तिष्यपुनर्वसुपर्यायवाचिनामपि यथा स्यात्—तिष्यपुनर्वसू सिध्यपुनर्वसू ॥

(प्रदीपः) यलोपे कृतमेव नक्षत्रग्रहणमित्यभिप्रायेण आह—अथ वेति । स्वरूपग्रहणे प्राप्तेऽर्थग्रहणार्थं द्वितीयं नक्षत्रग्रहणम् । पुनर्नक्षत्रग्रहणे सत्यर्थस्यैवायमनपेक्षितोपात्तशब्दस्यातिदेश इति पर्यायाणामपि ग्रहणसिद्धिः ॥

(उद्द्योतः) यलोप इति । तच्च पुष्यविशेषणार्थमावश्यकमेवेति भावः ॥ पुनर्नक्षत्रेति । तिष्यपुनर्वस्वोः शब्दयोरभिधेये नक्षत्रे वर्तमानानां नक्षत्रशब्दानां द्वन्द्व इति सूत्रार्थ इति भावः ॥ अर्थस्यैवेति । तदर्थसंबन्धिनो बहुत्वस्य द्वित्वातिदेश इत्यर्थः ॥

(आक्षेपभाष्यम्)

अथ द्वन्द्व इति किमर्थम्? ॥

(समाधानभाष्यम्)

यस्तिष्यस्तौ पुनर्वसू येषां त इमे तिष्यपुनर्वसव उन्मुग्धाः ॥

(प्रदीपः) तिष्यपुनर्वसव उन्मुग्धा इति । केचिदाहुः—पुरुषा अन्यपदार्थः नक्षत्राणां तु बहुव्रीहिरिति द्विवचनप्रसङ्गः ॥ अन्ये त्वाहुः—नक्षत्रवृत्तेः समासस्य ग्रहणे पुरुषाणामन्यपदार्थत्वे प्रसङ्ग एव नास्तीति ॥ अवयवेन विग्रहः समुदायः समासार्थ इति तिष्यादय एव विपर्यासविषया बहुव्रीहिणोच्यन्त इत्यस्ति प्रसङ्गः ॥

(उद्द्योतः) समासस्येति । कृत्तद्धितेति मन्त्रादिपरिणतविभक्तिकं समासग्रहणमनुवर्त्यत इत्यर्थः ॥ नास्तीतीत्यन्तेन पूर्वमतदूषणम् ॥ अथ भाष्यं व्याचष्टे—अवयवेनेत्यादिना । अवयवार्थकेन वर्तिपदार्थस्य बोधनमित्यर्थस्तदाह—समुदाय इति । उद्भूतावयवभेद इत्यर्थः ॥ विपर्यासविषया इति । यस्तिष्य इत्युपलक्षणं यौ पुनर्वसू स तिष्यो येषामित्यर्थस्यापीति भावः ॥ विपर्यासो भ्रमः ॥ उन्मुग्धा इत्यस्य च विपर्यासेन दृश्यमाना इत्यर्थः । अविविक्ततावचनान्मुहेः कर्तरि क्तेऽविविक्ता इत्यर्थादिति भावः ॥

(सर्वो द्वन्द्वो विभाषैकवदिति परिभाषाधिकरणम्)

(आक्षेपभाष्यम्)

बहुवचनस्येति किमर्थम्? ॥

(समाधानभाष्यम्)

उदितं तिष्यपुनर्वसु ॥

(प्रश्नभाष्यम्)

कथं चात्रैकवचनम्? ॥

(उद्द्योतः) भाष्ये—कथं चात्रेति । प्राण्यङ्गादीनामेव समाहारद्वन्द्व इति नियम इति भावः ॥

(समाधानभाष्यम्)

जातिद्वन्द्व एकवद्भवतीति ॥

(प्रदीपः) जातिद्वन्द्व इति । कथमनयोर्जातिशब्दत्वम् । यावता जातिप्रदेशेषु भिन्नाधारा जातिर्गृह्यते न त्वव्यस्थाभेदकल्पितभेदैकवस्तुविषया ॥ एवं तर्हि प्रतिमन्वन्तरे भिन्नानि नक्षत्राणीति दर्शने भिन्नाधारा जातिः संभवतीति न कश्चिद्दोषः ॥

(समाधानबाधकभाष्यम्)

अप्राणिनामिति प्रतिषेधः प्राप्नोति ॥

(परिभाषासिद्धिसमाधानभाष्यम्)

एवं तर्हि सिद्धे सति यद्बहुवचनग्रहणं करोति,

तज् ज्ञापयत्याचार्यः—"सर्वो द्वन्द्वो विभाषयैकवद्भवति" इति ॥ किमेतस्य ज्ञापने प्रयोजनम्? । बाभ्रवशालङ्कायनं बाभ्रवशालङ्कायना इत्येतत्सिद्धं भवति ॥

(प्रदीपः) **सर्वो द्वन्द्व इति** । अप्राणिजातिद्वन्द्वो नित्यमेकवद्भवति । प्राणिद्वन्द्वस्तु विकल्पेन । न्यायसिद्धश्चार्थो बहुवचनग्रहणेन लिङ्गेन सूच्यते ॥ एकवद्भावप्रकरणं हि विषयविभागार्थमारब्धम्—प्राण्यङ्गादीनां समाहार एव, न तु प्राण्यङ्गादीनामेव समाहार इति । ततस्तत्प्रकरणानुपात्तानां समाहारेतरेतरयोगयोर्द्वन्द्वः सिद्ध एव ॥

(उद्योतः) **एवं तर्हीति** । द्वन्द्वश्चेत्यादिषु—एषां समाहार एवेति नियमबोधनद्वारा तद्व्यतिरिक्तसर्वद्वन्द्वस्यानेनोभयरूपता बोध्यत इत्यर्थस्तदाह—**अप्राणीति** । न्यायसिद्धार्थद्योतकत्वेन सर्वशब्दस्य संकुचद्वृत्तितैव युक्तेति भावः । तद्ध्वनयन्नाह—**न्यायेति** ॥ एकवद्भावप्रकरणवैयर्थ्यमुद्धरन् न्यायमेव दर्शयति—**एकेति । विषयविभागो**, विषयनियमः । न तु विधेयद्वन्द्वनियमार्थमिति भावः ॥ **नत्विति** । अन्यथाऽत्र बहुवचनग्रहणवैयर्थ्यापत्तिरिति भावः ॥ **सिद्ध एवेति** । चार्थ इत्यनेनेत्यर्थः ॥

(समाधानान्तरभाष्यम्)

अथ वा नात्रभवन्तः प्राणिनः, प्राणा एवात्रभवन्तः ॥ तिष्यपुनर्वस्वो ॥ ६३ ॥

इति श्रीमद्भगवत्पतञ्जलिविरचिते व्याकरणमहाभाष्ये प्रथमस्याध्यायस्य द्वितीयपादे द्वितीयमाह्निकम् ॥

(प्रदीपः) **अथ वेति** । नह्येतेषु लोके प्राणिव्यवहारः प्रसिद्ध इति भावः ॥ **प्राणा एवेति** । तदधीनस्थितित्वात्प्राणिनामेत एव प्राणा उच्यन्ते ॥ ६३ ॥

इत्युपाध्यायजैयटपुत्रकैयटकृते महाभाष्यप्रदीपे प्रथमस्य द्वितीये पादे द्वितीयमाह्निकम् ॥ २ ॥

(उद्योतः) **नह्येतेष्विति** । **आपोमयः प्राण** इति श्रुतेरद्भिर्विना ग्लायमानप्राणा एव लोके प्राणिन इत्युच्यन्ते, इदमेव पूज्यत्वं भाष्येऽत्रभवच्छब्देनोच्यत इति भावः ॥ लोके प्राण इति व्यवहारस्याप्यभावादाह—**तदधीनेति** । एवं च तथा नियमेऽपि न क्षतिरिति भावः ॥ केचित्त्विष्टानुरोधेन **द्वन्द्वश्चे**त्यादिषु समाहार एवेति नियमः ॥ एवं चात्रापि पक्षे **जातिरप्राणिनामि**ति नित्यैकवद्भावे बहुवचनाभावात्सूत्रमनर्थकं सदुक्तार्थज्ञापकम् । ज्ञाप्यकोटौ सर्वशब्देनैकवद्भावविषयो जातिद्वन्द्व एव गृह्यते ॥ **द्वन्द्वश्चे**त्यादीनामन्येषां तु नित्यमेव । अत एवैकवद्भावप्रकरणं **पूर्वत्र नित्यार्थमुत्तरत्र व्यभिचारार्थमिति** विभाषा **वृक्षे**ति सूत्रस्थभाष्येण न विरोधः ॥ अत एव **मृदङ्गशङ्खतूणवा** इत्यादि संगच्छते ॥ यद्वा जातिप्राधान्य एकवचनं व्यक्तिप्राधान्ये च बहुवचनमित्युभयमप्यत्र । अत्रैवार्थे इदं ज्ञापकमित्याहुः ॥ ६३ ॥

इति श्रीशिवभट्टसुतसतीगर्भजनागोजीभट्टकृते भाष्यप्रदीपोद्द्योते प्रथमस्य द्वितीये द्वितीयमाह्निकम् ॥

आदित एकादशमाह्निकम् ॥

अथ

प्रथमाध्याये द्वितीये पादे तृतीयमाह्निकम् ।

(आदितो द्वादशमाह्निकम्)

(एकशेषप्रकरणमारभ्यते)

(११२ नियमसूत्रम् । १ । २ । ३ आ. १ सू.)

१३८ सरूपाणामेकशेष एकविभक्तौ ॥ १ । २ । ६४ ॥

(पदकृत्याधिकरणम्)

(आक्षेपभाष्यम्)

रूपंग्रहणं किमर्थम्? ॥

(प्रदीपः) **सरूपा ॥ ६४ ॥ रूपग्रहणमिति** । रूपस्यान्तरङ्गत्वादहेयत्वादुपदेशानपेक्षणाच्च तत्कृतमेव समानत्वं ग्रहीष्यते । प्रतिपत्तिलाघवं च समानानामित्युच्यमाने भवति । रूढशब्दत्वात्समानशब्दस्य तुल्यार्थत्वावगमात् । **सरूपाणा**मिति पुनरुच्यमाने पदद्वयार्थावगमपूर्वकान्यपदार्थावगमात् प्रतिपत्तिगौरवं भवतीति प्रश्नः ॥

(उद्योतः) **सरूपाणाम् ॥ ६४ ॥** नन्वर्थकृतमपि साम्यं गृह्येतेति प्रश्नानुपपत्तिरत आह—**रूपस्येति** ॥ **अन्तरङ्गत्वं**, शाब्दार्थप्रतीतेः पूर्वं नियमेन प्रतीयमानत्वम् । अर्थो हि तद्विपरीतत्वाद्बहिरङ्गः, तथानुकरणदशायामप्रतीतेर्हेयश्च । शब्दस्य तु ज्ञानमात्रे भानात्स कुत्रापि न हेयः ॥ **उपदेशः**, संबन्धग्रहः । पर्यायाप्रतिपाद्यमानत्वमसाधारणत्वम् ॥ ननु समानानामित्युक्तेऽपि वर्णकृतलाघवाभावोत आह—**प्रतिपत्तीति** । यद्यपि सह मानेनेतियोगस्तत्रापि तथापि प्रवीणादिवद्रूढ एवायमिति भावः । **तदाह—रूढशब्दत्वादिति** ॥ सरूपशब्दस्तु ज्योतिर्जनपदेति समानस्य सभावविधानादवयवानुसंधानद्वारेणैव सादृश्यं प्रतिपादयतीति तात्पर्यम् ॥

(समाधानभाष्यम्)

"समानानामेकशेष एकविभक्तौ" इतीयत्युच्यमाने यत्रैव सर्वं समानं शब्दोर्थश्च, तत्रैव स्याद् वृक्षाः प्लक्षा इति । इह न स्याद्—अक्षाः पादा

आप्यते इति । रूपग्रहणे पुनः क्रियमाणे न दोषो भवति । रूपं निमित्तत्वेनाश्रीयते । श्रुतौ च रूपग्रहणम् ॥

(प्रदीपः) शब्दोर्थश्चेति । स्वं रूपमित्यत्र रूपग्रहणेन ज्ञापितम्—व्याकरणे रूपवदर्थोप्यङ्गीक्रियत इति । ततश्चार्थरूपाभ्यां समानत्वं गृह्यतेत्यर्थः ॥ शब्दानुशासनप्रस्तावाच्च शब्दसंबन्धिरूपं गृह्यते, न तु चक्षुर्ग्राह्यमित्याह—श्रुतौ चेति । श्रोत्रोपलब्धावित्यर्थः । अथ वा श्रोत्रेन्द्रियं श्रुतिरुच्यते ॥

(उद्द्योतः) ज्ञापितमिति । शब्दार्थविषये क्वचिदुक्तन्यायाप्रवृत्तेर्ज्ञापनादित्यर्थः ॥ श्रोत्रेन्द्रियस्य करणत्वेप्याधारत्वासंभवादाह—श्रोत्रोपेति । भावसाधनः श्रुतिशब्द इति भावः ॥ अथ वेति । श्रुत्यवच्छेदेनेत्यर्थः । करणसाधनः स इति भावः ॥ आद्ये ग्रहणं विषयता, द्वितीये तु प्रतीतिरिति विवेकः । प्राधान्येन श्रोत्रेन्द्रियग्राह्यं वस्त्वत्र रूपशब्देनोच्यत इति तात्पर्यम् ॥

(॥ इति रूपग्रहणप्रयोजनम् ॥)

(आक्षेपभाष्यम्)

अथैकग्रहणं किमर्थम् ? ।

(प्रदीपः) **एकग्रहणमिति** । शेषणं शेष इति भावसाधनपक्षे प्राथम्यादेकस्यैव शेषो भविष्यति । शिष्यत इति शेष इति कर्मसाधनपक्षेप्येकत्वसंख्याया विवक्षितत्वादेक एवावशिष्यत इति प्रश्नः ॥

(उद्द्योतः) शेषणमिति । अन्येतरनिवृत्तिविशिष्टमवस्थानं विधेयम् । तत्रैकस्य द्वयोरित्याद्याकाङ्क्षायां प्राथम्यादेकस्यैव भविष्यतीत्यर्थः ॥ कर्मसाधनेति । तत्र हि सरूपाणां संबन्धी शिष्यत इत्यर्थः । तत्राक्षिप्तसंबन्धिपदे आक्षेपकसामानाधिकरण्यायैकवचनान्ते एकत्वविवक्षेति भावः ॥

(समाधानभाष्यम्)

'सरूपाणां शेष एकविभक्तौ' इतीयत्युच्यमाने द्विबह्वोरपि शेषः प्रसज्येत । एकग्रहणे पुनः क्रियमाणे न दोषो भवति ॥

(प्रदीपः) **द्विबह्वोरिति** । द्वित्वबहुत्वविषयस्यानेकस्य शब्दस्येत्यर्थः । तत्र भावसाधनपक्षे व्यासिन्यायाश्रयेणानेकस्यापि शेषः स्यात् । कर्मसाधनपक्षेपि संस्कार्यत्वात् प्राधान्यात्संख्याया अविवक्षा स्यात् । यथा ग्रहं संमार्ष्टीति भावः ॥

(उद्द्योतः) संख्येयार्थकत्वे द्विवचनानुपपत्तिः, संख्यार्थत्वेऽर्थासङ्गतिरत आह—द्वित्वेति । द्विबह्वोरिति विषयसप्तमीति भावः ॥ शेषशब्दोत्र नोपयुक्तादन्यस्मिन्, असम्भवात् । तदाह—तत्र भावेति ॥ व्यासीति । अत्र शास्त्रे आद्युदात्तश्चेत्यादिग्रहणेन प्रागुरीश्वरादिति रेफोच्चारणेन प्राथम्यन्यायापेक्षया व्यासिन्यायस्य प्राबल्यबोधनाद् । एवं चेतरनिवृत्तिमदवस्थानं तदर्थः । तत्र यद्यपि स्थितेः सिद्धत्वान्निवृत्तावेवार्थतो विधेयता तथापि शब्दतस्तत्रैव विधेयत्वाद् व्यासिन्यायेन द्विबहूनामेवावस्थानं स्यादेकस्य निवृत्तिरिति भावः ॥ संस्कार्यत्वादिति । शिष्यमाणत्वविधानेन शेषपदार्थाक्षिप्तस्य संस्क्रियमाणत्वादिति भावः ॥

(इति प्रथमैकशब्दप्रयोजनम्)

(अथ शेषग्रहणप्रयोजनम्)

(आक्षेपभाष्यम्)

अथ शेषग्रहणं किमर्थम् ? ।

(प्रदीपः) **शेषग्रहणमिति** । सरूपाणामेकः प्रादुर्भवतीति वाक्यशेषोध्याहरिष्यत इति भावः ॥

(उद्द्योतः) सरूपाणामिति । षष्ठ्या विधेयबोधकशेषपदेन सामानाधिकरण्यान्वययोग्यः संबन्धी आक्षिप्यते स चैकवचनान्त एव यद्यपि, तथापि तस्य विधेयेन शिष्यमाणत्वेन संस्क्रियमाणत्वेनानुवाद्यत्वादेकत्वाविवक्षेति तात्पर्यम् ॥ सरूपाणामिति लक्ष्यानुसारतो व्याख्यानमाश्रित्यैषा निर्धारणे षष्ठी, साध्वनुशासनत्वाच्च साधुरित्याद्यध्याहारः । एवं च तेषां मध्ये एकस्य साधुत्वेऽपरस्यासाधुत्वेनार्थान्निवृत्तिरिति भावः ॥

(समाधानभाष्यम्)

"सरूपाणामेक एकविभक्तौ" इतीयत्युच्यमाने आदेशोयं विज्ञायेत ॥

(प्रदीपः) **आदेशोयमिति** । षष्ठी स्थानेयोगेति नियमात् ॥

(उद्द्योतः) षष्ठीति ॥ निर्दिश्यमानस्यादेशा इत्यर्थमावश्यकस्य व्याख्यानापेक्षगौरवपरिहाराय नियमार्थत्वमप्यङ्गीकार्यमिति निर्धारणषष्ठी न युक्तेति भावः ॥

(आदेशविज्ञाने दूषणजिज्ञासाभाष्यम्)

तत्र को दोषः ? ।

(प्रदीपः) **तत्र को दोष इति** । अंतरतम एक आदेशः प्रवर्तिष्यत इति भावः ॥

(उद्द्योतः) अन्तरतम इति । शब्दतोर्थतश्चेत्यादिः । तमग्रहणादिति भावः ॥

(दोषप्रदर्शकभाष्यम्)

अश्वश्चाश्वश्चाश्वौ । आन्तर्यतो द्व्युदात्तवतः स्थानिनो द्व्युदात्तवानादेशः प्रसज्येत ॥

लोप्यलोपिता च न प्रकल्पेत ॥

(प्रदीपः) इतरत्र स्वरे दोषमाह—**अश्वश्चाश्वश्चेति** ॥ **द्व्युदात्तवत इति** । द्वावुदात्तवन्तावश्वशब्दौ यस्य समुदायस्य स द्व्युदात्तवान् समुदायः । आदेशोपि द्व्युदात्तवन्तावुदात्तगुणयुक्तावकारौ यस्येति द्व्युदात्तवानुच्यते ।

एतच्चोपलक्षणं तेन ह्यनुदात्तस्य ह्यनुदात्त आदेशः प्राप्नोति ॥ **लोप्यलोपितेति** । लोपनीयस्य लोपित्वं लोपसंबन्धो न प्राप्नोतीत्यर्थः ॥

(**उद्द्योतः**) ह्युदात्तशब्दस्य बहुव्रीहित्वे मतुप् न स्यादुक्तार्थत्वात्, कर्मधारयात्तु मत्वर्थीयो नेष्ट इत्यत आह—**द्वाविति** । अत्रोदात्तशब्दो धर्मिपरः ॥ आदेशस्यापि तथात्वे एकशेषानर्थक्यमत आह—**आदेशोपीति** । अत्रोदात्तशब्दो धर्मपर इति भावः ॥ विधीयमानानेकोदात्तस्योभे वनस्पत्यादिषु युगपदित्यादौ समावेशदर्शनादिति तात्पर्यम् ॥ **तेनेति** । पर्यायेणेति भावः ॥ नन्वश्वशब्दे श्रूयमाणोदात्तानुदात्तयोरनुग्रहायान्तरतमपरिभाषयोभयस्वरक एवादेशो भविष्यतीति चेन्न । तेनैव रूपेण साहृदयग्रहणमित्यत्र नियामकाभावेन पर्यायस्य दुर्वारत्वात् । यत्तु इश्च इश्चेत्येकशेषे एक आदेशोऽलरूपत्वादन्त्यस्य स्यात् । सूत्रं त्वनेकाल्त्वु चरितार्थं ततः सवर्णदीर्घे **दीर्घा**दिति पूर्वसवर्णदीर्घनिषेधे यणि यावित्ति स्यादित्याहुः ॥ तत्र **सरूपाणा**मिति बहुवचनेन प्रत्येकं स्थानित्वबोधनेन रमागमन्यायेन सर्वनिवृत्तेरदोषात् ॥

लोप्यलोपिपदयोः पौनरुक्त्यमाशङ्कयाह—**लोपनीयस्येति** । लोप्यपदम्**हलोरि**तिण्यदन्तम् ॥ **संबन्ध इति** । कृत्तद्धितसमासेभ्यो भावप्रत्ययस्य संबन्धाभिधायकत्वादिति भावः ॥

(लोप्यलोपिप्रकृत्यभावे दूषणजिज्ञासाभाष्यम्)

तत्र को दोषः? ।

(दोषप्रदर्शकभाष्यम्)

गर्गा वत्सा विदा उर्वाः । यञ्यो बहुष्वञ्यो बहुष्वित्युच्यमानो लुङ् न प्राप्नोति ॥

(**प्रदीपः**) **गर्गा इति** । प्रकृतिरर्थाभेदादेकैव । यञ्प्रत्ययास्तु बहवः । यञाकृतेश्च एकत्वाद् व्यवधानाभावादनेकस्यापि प्रत्ययस्य परत्वं न विरुध्यते । तत्र गर्ग य य य इति स्थिते यदा गर्गशब्दं मुक्त्वा प्रत्ययानामेवैको यशब्द आदेशः क्रियते तदा तस्य बह्वर्थत्वाल्लुक् सिध्यति । यदा तु विरूपाणामपि समानार्थानामेकशेषवद्रेक आदेशः सप्रकृतिकः क्रियते तत्र गर्ग य इत्यस्यान्ययोश्च यशब्दयोर्गर्गयशब्द आदेशः । तत्र यशब्दान्तस्य बहुषु वृत्तिः न तु प्रत्ययमात्रस्येति भावः ॥

(**उद्द्योतः**) **एकैवेति** । गर्गस्यापत्यानीति विवक्षणादिति भावः ॥ **बहव इति** । अपत्यानां बहुत्वात् ॥ नन्वेकस्याः प्रकृतेः कथं बहवः परेऽत आह—**यञाकृतेश्चेति** । यद्यपि जातेरेकैकव्यक्तिव्यङ्ग्यत्वं व्यक्तिद्वारकमेव परत्वं च, तथाप्यव्यवहितव्यक्तिद्वारकं सर्वगतजातेः परत्वमित्यभिमानः । व्यक्तिपक्षेपि विजातीयव्यक्तिव्यवधानमेव व्यावर्त्यते, न सजातीयतद्व्यवधानमित्यन्ये ॥ **प्रत्ययानामेवेति** । समानाकारत्वादिति भावः । इदं चिन्त्यमेकविभक्ताविन्युक्त्या तत्प्रकृतित्वायोग्यानां केवलप्रत्ययानामेकशेषाप्राप्तेः । गर्गसहितानामेव हि तत्प्रकृतिता ॥ **विरूपाणामिति** । अन्त्ययशब्दयोरपि गर्गापत्यत्वेनैव बोधकत्वात्समानार्थत्वं बोध्यम् । वदित्युक्तिस्तु संप्रतिपन्नविषयाभिप्रायेण ॥

(समाधानबाधकभाष्यम्)

मा भूदेवम् । यञन्तं यद्बहुषु अञन्तं यद्बहुष्वित्येवं भविष्यति ॥

(**प्रदीपः**) **यञन्तं यद्बहुष्विति** । आदेशपक्षेपि वचनसामर्थ्यात् सारूप्यात् यञ्बुद्ध्युत्पादाद्यञन्तमेतदित्याश्रीयते ॥

(**उद्द्योतः**) नन्वादिश्यमानगर्गयशब्दान्तर्गतयशब्दस्यान्यत्वेन कथं यञन्तत्वादीत्यत आह—**आदेशपक्षेपीति** । **वचनसामर्थ्यादिति** । लुग्वचनसामर्थ्यादित्यर्थः ॥ **यञ्बुद्धीति** । एतेनावयवस्याप्रत्ययत्वाद् लुगसम्भव इति परास्तम् ॥

(समाधानसाधकभाष्यम्)

नैवं शक्यम्, इह हि दोषः स्यात्—काश्यपप्रतिकृतयः काश्यपा इति ॥

(**प्रदीपः**) **काश्यपा इति** । काश्यप इवायं तत्प्रतिकृतिरितीवे **प्रतिकृता**विति विहितस्य कनो **जीविकार्थे चापण्य** इति लुप् । ततः काश्यपश्च काश्यपश्च काश्यपश्चेति प्रतिकृतिप्रचयविवक्षायामेकः काश्यपशब्दः प्रयुज्यते । स च बह्वर्थोऽञन्तश्चेति लुक्प्रसङ्गः । लौकिकस्य गोत्रस्य तत्र ग्रहणमिति परिहार उत्तरत्र वक्ष्यते इतीह नोक्तः ॥

(**उद्द्योतः**) **लौकिकस्य गोत्रस्येति** । प्रवराध्यायप्रसिद्धस्येत्यर्थः । यस्कादिभ्य इत्यतो गोत्रे इत्यनुवृत्त्या गोत्रबहुत्वे वर्तमानस्य यञन्तस्य लुगिति व्याख्यानात् । इदं च प्रतिकृतिबहुत्वे वर्तते न तु गोत्रबहुत्वे इत्यदोष इति भावः ॥ **लौकिकस्येति** । सिद्धान्तस्वरूपकथनम् ॥

(इति शेषपदप्रयोजनम्)

(आक्षेपभाष्यम्)

एकविभक्ताविति किमर्थम्? ।

(समाधानभाष्यम्)

पयः पयो जरयति वासो वासश्छादयति ब्राह्मणाभ्यां च कृतं ब्राह्मणाभ्यां च देहीति ॥

(**प्रदीपः**) **पय इति** । उत्तरत्रार्थविप्रतिषेधादिति प्रत्याख्यानं करिष्यते ॥

(**उद्द्योतः**) एकग्रहणविषयः प्रश्न इत्यभिप्रायेणोत्तरयति—भाष्ये—**पय इति** । भिन्नविभक्तिव्यावृत्त्यर्थमेकग्रहणमिति भावः ॥

(इत्येकविभक्तौ पदप्रयोजनम्)

(अथ सूत्रप्रयोजनम्)

(आक्षेपभाष्यम्)

किमर्थं पुनरिदमुच्यते? ।

(प्रदीपः) **किमर्थं पुनरिति** । जातिः शब्दार्थः । तस्याश्चैकत्वादनेकशब्दाप्रयोगः । आश्रयगतसंख्याप्रतिपादनाय च द्विवचनबहुवचने भविष्यत इति प्रश्नः ॥

(उद्योतः) ननु सूत्राभावे सरूपाणां द्वन्द्वापत्तिरत आह—जातिरिति ॥

(७२३ समाधानवार्तिकप्रथमखण्डम् ॥)

॥ * ॥ प्रत्यर्थं शब्दनिवेशान्नैकेनानेकस्याभिधानम् ॥ * ॥

(भाष्यम्) **प्रत्यर्थं शब्दा अभिनिविशन्ते ॥ किमिदं प्रत्यर्थमिति? । अर्थमर्थं प्रति प्रत्यर्थम् । प्रत्यर्थं शब्दनिवेशाद् । एतस्मात्कारणाद् नैकेन शब्देनानेकस्यार्थस्याभिधानं प्राप्नोति ॥**

(प्रदीपः) द्रव्य पदार्थ उपलक्षणं त्वाकृतिरिति दर्शने सूत्रमारब्धव्यमित्याह—**प्रत्यर्थमिति** । यावन्ति द्रव्याणि विशिष्टगुणक्रियाविषयतया विवक्षितानि तावतां शब्दानामेकैकार्थोपक्षयाणां प्रयोगे प्राप्ते एकशेषारम्भ इत्यर्थः ॥

(उद्योतः) **द्रव्यमिति** । तत्र हि प्रत्यर्थं शब्दनिवेश इतिन्यायात्तत्तद्व्यक्तिप्रतिपादनाय नानाशब्दप्रयोगः प्राप्नोतीत्यर्थः ॥ **उपलक्षणं त्विति** । यो रक्तवासाः स देवदत्त इत्यादौ रक्तवासस्त्ववदित्यर्थः । अन्यथानन्त्यात्तत्र शक्तिग्रहो न स्यात् । केवला व्यक्तिरेव शब्दार्थः । जातेः शक्तिग्रहे प्रकारत्वेपि न तत्र शक्यतावच्छेदकता, नापि शक्यता, शुद्धव्यक्तेरेव च शब्दाज्ज्ञानम् शब्दस्यैव बोधे प्रकारतया न निर्विकल्पकत्वं तस्य । तत्पक्षे चानुगतधर्माभावान्न तेनानुगतानेकव्यक्तिबोधसम्भव इति सूत्रमिति भावः ॥ **विशिष्टगुणक्रियाविषयतयेति** । तदाश्रयत्वेनोपलक्षितानीत्यर्थः ॥ अपरे तु **किमर्थमिति** प्रश्नभाष्यस्य तत्रैव सिद्धिरित्याशयः । तत्प्रकारणं च शब्दानां तुल्यरूपता, यथाऽक्षा भज्यन्तां भक्ष्यन्तां दीव्यन्तामिति ॥ **प्रत्यर्थमिति** । अक्षा दीव्यन्ताम् । अक्षा भज्यन्ताम् । अक्षा भुज्यन्तामित्यादौ वाक्ये प्रत्यर्थशब्दनिवेशस्यापि दर्शनात्कदाचित्तादृशप्रयोगे सहविवक्षायां प्राप्तद्वन्द्वनिवृत्त्यर्थं सूत्रमावश्यकमित्याशयः ॥ **किमिदं प्रत्यर्थमिति** । अर्थावर्थौ प्रतीत्यादेरपि तदर्थस्य संभवात्प्रश्नः । एकवचनान्तेन विग्रह इत्युत्तरम् ॥ **नैकेनेति** । नैकेनैवेत्यर्थः ॥

(आक्षेपभाष्यम्)

तत्र को दोषः? ।

(७२४ समाधानवार्तिकद्वितीयखण्डम् ॥ १ ॥)

॥ * ॥ तत्रानेकार्थाभिधानेनेकशब्दत्वम् ॥ * ॥

(भाष्यम्) **तत्रानेकार्थाभिधाने अनेकशब्दत्वं प्राप्नोति । इष्यते च एकेनाप्यनेकस्याभिधानं स्यादिति ॥ तच्चान्तरेण यत्नं न सिध्यति । तस्मादेकशेषः । एवमर्थमिदमुच्यते ॥**

(उद्योतः) **अनेकशब्दत्वमिति** । अनेकशब्दत्वमेवेत्यर्थः ॥ **एकेनापीति** । अपिना वाक्यसंग्रहः । शास्त्रेण सहविवक्षाविषयशास्त्रीयद्वन्द्वस्यैव वारणादिति भावः ॥

(काकुभाष्यम्)

अस्ति प्रयोजनमेतत् ॥ किं तर्हीति ॥

(आक्षेपभाष्यम्)

किमिदं प्रत्यर्थं शब्दा अभिनिविशन्त इत्येवं दृष्टान्तमास्थाय सरूपाणामेकशेष आरभ्यते, न पुनरप्रत्यर्थं शब्दा अभिनिविशन्त इत्येतं दृष्टान्तमास्थाय विरूपाणामनेकशेष आरभ्यते? ॥

(प्रदीपः) **किमिदमिति** । यदि हेतुरहितं दृष्टान्तमाश्रित्य विरूपानेकशब्दप्रयोगदर्शनात्सरूपैकशेष आरभ्यते, तदा सरूपैकशब्दप्रयोगदर्शनाद्विरूपानेकशेषः किमिति नारभ्यत इति प्रश्नः । प्रयोगात्तु शब्दशक्तावनुगम्यमानायां न किंचिदारब्धव्यम् । द्रव्यपदार्थपक्षेपि स्वभावादेकः शब्दोऽनेकमर्थं द्यावादिवत् प्रत्याययिष्यति । अन्यथा एकशेषारम्भेपि कथं प्रत्यायकः स्यात् । नहि स्वतोऽसती शक्तिराचार्येण कर्तुं शक्यते । मन्दबुद्धिव्युत्पादनार्थं च यथास्थितप्रयोगानुसरणे कोनुरोधः सरूपैकशेषारम्भे न पुनर्विरूपानेकशेषारम्भे ॥

(उद्योतः) **किमिदमिति** । अक्षा इत्यादावेवाप्रत्यर्थशब्दनिवेशस्यापि दृष्टत्वेन विरूपविषयेपि लाघवायैकशब्दप्रयोग एव प्राप्तेऽनेकशब्दप्रयोगाय विरूपाणामनेकशेष एव कुतो नारभ्यत इत्यर्थ इत्याहुः ॥ **हेतुरहितमिति** । प्रत्यर्थमित्यादिस्तु न हेतुः, अपक्षवृत्तित्वादिति भावः । अत एव भाष्ये **दृष्टान्तमास्थायेत्युक्तम्** ॥ **विरूपानेकशेष इति** ॥ नन्वनेकशेष इत्यस्यानेकस्य शेष इत्यर्थो वा, एकशेषो नेत्यर्थो वा, एकशेषभिन्नो भवतीत्यर्थो वा । नाद्यः । त्रिषु प्रतिपाद्येषु द्वयोः प्रयोगापत्तेः । शेषशब्दस्वारस्येनैकनिवृत्तेरावश्यकत्वात् । न द्वितीयः । एकशेषाप्राप्त्याऽसंभवादिति चेन्न । तृतीयेऽदोषात् । तत्रापि भिन्नशब्देन द्वन्द्व एव न तु वाक्यं, **वृद्धो यूनेत्यादौ** प्रसिद्धैकशेषस्य पुष्पवन्ताविति न्यायेन सहविवक्षाविषयस्यैव सत्त्वेन तद्भिन्नस्य सहविवक्षाविषयस्य शास्त्रीयस्यैव ग्रहीतुमुचितत्वात् । तत्रेदं वचनं न घटपटावित्यादिविषयम् अप्रत्यर्थशब्दनिवेशे शब्दानां तुल्यरूपताया बीजत्वेन तदभावेन तस्याप्राप्तेः । किं तु जननीपरिच्छेदकर्त्रादिवाचकमात्रादिशब्दविषयं, तयोरौजसादौ वैरूप्यात् । अत्रापि विभक्तावित्यावश्यकम् । अन्यथा हरितवर्णविशिष्टस्त्रीहरिणस्त्रीवाचकयोर्हरिणीशब्दयोस्तद्धिते वैरूप्येणानेकशेषापत्तेः । विभक्तिसामानाधिकरण्येन च वैरूप्यान्वयोन्यथाऽसंभवात् । तत्रेदं न विधायकं, **चार्थे द्वन्द्व** इत्यनेनैव सिद्धेः । किं तु नियमार्थं, तेन लोकसिद्धसहविवक्षाविषयतत्प्रव्यावृत्तिस्तथा विरूपाणामेव द्वन्द्व इति च नियमः । अन्यथैकशेषारम्भेणास्य समफलकत्वानापत्तिः । तच्यासे हि स येन नाप्राप्तिन्यायेन द्वन्द्व-

बाधक इति सरूपाणां द्वन्द्वाभावस्येष्टत्वात् । अनेकशेषपदेन वावृत्त्या विरूपाणां तन्न्यायसिद्धलौकिकैकशेषाभावोपि बोध्यते । न चास्मार्थस्यैकशेषारम्भे कथं सिद्धिः । आवृत्त्या सरूपाणामेवैकशेष इति नियमस्याप्यङ्गीकारादिति बोध्यम् ॥ ननु विरूपाणां विभिन्नार्थानां नैकस्यानेकार्थाभिधानशक्तिमत्त्वमित्येकशब्दाप्रयोगान्नानेकशेष आरम्भणीयोत आह—प्रयोगास्त्विति । व्युत्पादनार्थं वेति पाठे वाशब्दश्चार्थे । क्वचित् चेत्येव पाठः ॥ प्रयोगानुसरणे इति । प्रयोगाणां शास्त्रेणानुसरणे अन्वाख्याने इत्यर्थः ॥

(आक्षेपबाधकभाष्यम्)

तत्रैतत्स्यात्—लघीयसी सरूपनिवृत्तिः, गरीयसी विरूपप्रतिपत्तिः ॥

(आक्षेपसाधकभाष्यम्)

तच्च न । लघीयसी विरूपप्रतिपत्तिः । किं कारणम् ? । यत्र हि बहूनां सरूपाणामेकः शिष्यते तत्रावरतो द्वयोः सरूपयोर्निवृत्तिर्वक्तव्या स्याद् ।

(प्रदीपः) लाघवायैकशेषारम्भश्चेत्तन्न । लघीयसी विरूपप्रतिपत्तिः । तत्र हि प्रवृत्तिविषया बुद्धिरेकरूपैव भवति । एकशेषे तु प्रवृत्तिनिवृत्तिविषयेति प्रतिपत्तिगौरवप्रसङ्गः ॥ **अवरतो द्वयोरिति** । यदा त्रयाणामेकः शिष्यते तदा द्वयोर्निवृत्तिर्वक्तव्या व्याख्येयेत्यर्थः । शेषशब्दस्य निवृत्तिविशिष्टावस्थानवाचित्वात् । यदा तु द्वयोरेकशेषस्तदैकस्य निवृत्तिः । चतुष्प्रभृतीनां त्वेकशेषे त्रिप्रभृतीनां निवृत्तिरिति प्रवृत्तिनिवृत्तिलक्षणविषयभेदाद्बुद्धिगौरवापत्तिरित्यर्थः ॥

(उद्द्योतः) **लाघवायेति** । सुशब्दोपदेशेनापशब्दनिवृत्तिवदेकशेषारम्भेणानेकशेषनिवृत्तेः सिद्धत्वादिति भावः ॥ **यदा तु द्वयोरिति** । सरूपौ च सरूपाश्चेत्येकशेषेण निर्देशादिति भावः । एवं चावरतो द्वयोरिति भाष्यं यत्र बहूनामेकशेषस्तद्विषयमेवेति तात्पर्यम् ॥

(समाधानभाष्यम्)

एवमप्येतस्मिन् सति किंचिदाचार्यः सुकरतरकं चैकशेषारम्भं मन्यते ॥

(प्रदीपः) **सुकरतरकं चेति** । एवं हि प्रकरणमभिन्नरूपं भवति वृद्धो यूनेत्यादिभिः सूत्रैरेकशेषस्य विधानात् । अनेकशेषारम्भे त्विह पृथक्प्रस्थानतया गौरवं स्यादित्यर्थः ॥

(उद्द्योतः) नन्वेकशेषारम्भस्य गुरुत्वेन सुकरत्वमेव नास्ति कुतः सुकरतरकत्वमित्यत आह—**एवं हीति** ॥ **पृथक्प्रस्थानतया** । पृथक्प्रकरणतया । वृद्धो यूनेत्याद्यर्थं चैकशेषोऽवश्यं वाच्य इति भावः ॥

(एकशेषस्यानैमित्तिकत्वसाधनाधिकरणम्)

(आक्षेपभाष्यम्)

किं पुनरयमेकविभक्तावेकशेषो भवति ? ॥

(प्रदीपः) **किं पुनरिति** । किमयमेकशब्दः संख्यावाची तुल्यतावाची वेति प्रश्नः ॥

(उद्द्योतः) **संख्येति** । तेनैकदिगितिवत्समानवाचित्वे पृथक् सर्वेभ्य उत्पन्नाया विभक्तेर्निमित्तत्वलाभाद्वार्तिकोत्थानं भज्येत । एवं चैकशेषविषयसरूपसमुदायादेकत्वसंख्याविशिष्टविभक्तौ परत एकशेष इत्यर्थः किमिति प्रश्न इति भावः ॥

(तटस्थभाष्यम्)

एवं भवितुमर्हति ।

(प्रदीपः) **एवं भवितुमिति** । संख्यावाचित्वेनैकशब्दस्य प्रसिद्धतरत्वात् ॥

(उद्द्योतः) प्रष्टुराशयं विज्ञातुमाहेतरो भाष्ये—एवमित्यादि ॥

(७२५ पूर्वपक्ष्याक्षेपवार्तिकम् ॥ ३ ॥)

॥ * ॥ एकविभक्ताविति चेन्नाभावाद्विभक्तेः ॥ * ॥

(भाष्यम्) **एकविभक्ताविति चेत्तन्न ॥ किं कारणम् ? ॥ 'अभावाद्विभक्तेः' नहि समुदायात्परा विभक्तिरस्ति ॥ किं कारणम् ?॥ अप्रातिपदिकत्वात् ॥**

(प्रदीपः) **नाभावादिति** । ङ्याप्प्रातिपदिकादित्यत्रैकवचनान्तानामेव द्वन्द्वः क्रियते । वर्तिपदार्थानां सर्वत्र संख्याभेदावगमे प्रमाणाभावात् । गुणे च संख्या विवक्ष्यते यथा **पशुना यजेतेति** । एवं चैकैकस्मात् प्रातिपदिकात् स्वादिभिरुत्पत्तव्यं न तु समुदायात् । यत्र क्वचिद्गुणेपि संख्या न विवक्ष्यते यथा **कर्तुरीप्सिततममिति** द्वयोर्बहूनां वेप्सिततमस्य कर्मसंज्ञा प्रवर्तते, तत्र नान्तरीयकं संख्याया उपादानमिति लक्ष्यसिद्ध्यर्थमाश्रीयते ॥

(उद्द्योतः) प्रष्टा स्वाशयमाह—**एकेत्यादि** ॥ **संख्याभेदावगमे** । द्वित्वाद्यवगमे इत्यर्थः ॥ एवमपि प्रातिपदिकादित्येकत्वस्य विवक्षायां न मानमत आह—**गुणे चेति** । संस्कार्यत्वादिति भावः ॥ **यथा कर्तुरिति** । कर्तुरित्यत्रेति भावः ॥ **लक्ष्यसिद्ध्यर्थमिति** । एवं च पशुनेत्यादि दृष्टान्तदानमभ्युच्चयो, विधेयगता संख्या विवक्षिता नानुवाद्यगतेत्येव मीमांसकमर्यादेति भावः ॥ वस्तुतस्तु समुदायस्य प्रातिपदिकत्वाभावादिति भाष्ये उक्तं, प्रातिपदिकत्वपर्याप्त्यधिकरणात्प्रत्यय इति हि सूत्रार्थः । नहि प्रातिपदिकसमुदाये प्रातिपदिकत्वम् । यथा जनपदसमुदाये न जनपदत्वमिति कैयटोक्तार्थोपयोगश्चिन्त्यः ॥

(आक्षेपबाधकभाष्यम्)

ननु चार्थवत् प्रातिपदिकमिति प्रातिपदिकसंज्ञा भविष्यति ॥

(प्रदीपः) **ननु चेति** । अवयवार्थातिरेकेण परस्परापेक्षायां सत्यां समुदायार्थोपजननात् सरूपसमुदायाभिनिवेशिन्येका प्रातिपदिकसंज्ञास्ति तया सरूपसमुदाय एकं प्रातिपदिकमिति स्वाद्युत्पत्तिरविरुद्धा ॥

(उद्द्योतः) परस्परापेक्षायां कार्यविशेष इति शेषः॥ समुदायार्थः। समूहरूपः॥ समुदाय इति। समुदायोपीत्यर्थः॥

(आक्षेपसाधकभाष्यम्)

नियमान्न प्राप्नोति—अर्थवत्समुदायानां समासग्रहणं नियमार्थमिति॥

(प्रदीपः) अर्थवत्समुदायानामिति। अविशेषेण नियमो न तु सुबन्तानामेवेति मन्यते॥

(उद्द्योतः) ननु सुबन्तानामिति। भेदसंसर्गद्वारकार्थवतामुपलक्षणमिदम्॥

(प्रथमपक्षाभ्युपगमभाष्यम्)

यदि पुनः "पृथक्सर्वेषां विभक्तिपराणामेकशेषः" उच्यते।

(प्रदीपः) इदानीं तुल्यपर्यायमेकशब्दमाश्रित्याह—यदि पुनरिति॥

(उद्द्योतः) तुल्येति। यथैकदिगित्यादौ प्रसिद्धतरार्थानुपपत्तौ प्रसिद्धार्थपरिग्रहो न्याय्य इति भावः॥

(७२६ दूषणवार्तिकम्॥ ४॥)

॥ * ॥ पृथक्सर्वेषामिति चेदेकशेषे पृथग्विभक्त्युपलब्धिस्तदाश्रयत्वात्॥*॥

(भाष्यम्) **पृथक्सर्वेषामिति चेद् एकशेषे पृथग्विभक्त्युपलब्धिः प्राप्नोति॥**

किमुच्यते एकशेषे पृथग्विभक्त्युपलब्धिरिति?॥ यावता समयः कृतः—"न केवला प्रकृतिः प्रयोक्तव्या न च केवलः प्रत्ययः" इति। तदाश्रयत्वात् प्राप्नोति। यत्र हि प्रकृतिनिमित्त प्रत्ययनिवृत्तिस्तत्राप्रत्ययिकायाः प्रकृतेः प्रयोगो भवति—अग्निचित्सोमसुदिति यथा। यत्र च प्रत्ययनिमित्ता प्रकृतिनिवृत्तिस्तत्राप्रकृतिकस्य प्रत्ययस्य प्रयोगो भवति—अधुना इयानिति यथा॥

(प्रदीपः) पृथक् सर्वेषामिति। वृक्षस् इति स्थिते विभक्तौ परतो यानि सरूपाणि तेषामेकशेष उच्यमाने विभक्तिनिमित्तत्वात् प्रकृतिनिवृत्तेः केवलानां विभक्तीनां प्रयोगप्रसङ्ग इत्यर्थः॥

(उद्द्योतः) तुल्यत्वं भेदाधिष्ठानं तेन पृथक् सर्वेभ्यः शब्देभ्यतश्च तुल्यायां विभक्तौ परत एकशेष इति तात्पर्यम्। अर्थतश्चेत्युक्तेः प्रथमाद्वितीयाद्विवचनान्तानां नैकशेषः। विनिगमनाविरहादर्थतश्चेत्यस्य लाभस्तदाह—वृक्षसित्यादि॥ केवलानामिति। निवृत्तप्रकृतीनामित्यादिः॥ भाष्ये—तदाश्रयत्वादिति। बहुव्रीहिरत्वः। विभक्त्याश्रयत्वात्तत्प्रकृत्येकशेषस्येत्यर्थः। न केवलेत्यस्य चानुत्पन्नप्रत्यया प्रकृतिः प्रकृतेरनुत्पन्नश्च प्रत्ययो न प्रयोक्तव्य इति तात्पर्यमिति भावः॥ अधुनेति। यदेदमोऽधुना प्रत्यय इशो लोपश्च तदेदम्, निमित्तापायपरिभाषा नास्त्येवेत्यन्यत्र प्रपञ्चितम्॥

(दूषणबाधकभाष्यम्)

अस्तु। संयोगान्तलोपेन सिद्धम्॥

(प्रदीपः) **संयोगान्तलोपेनेति।** वृक्षस् स् स् इति स्थिते संयोगान्तलोपो भविष्यति॥ ननु संयोगान्तस्य पदस्य लोप उच्यते तत्र पूर्वपदं सकारान्तं द्वौ सकारौ पदे इति पदत्रयं संपद्यत इति कुतो लोपः। संयोगान्तलोपस्य चापवादः संयोगादिलोपस्तेन भाव्यम्। पूर्वत्रासिद्धमिति वचनाद्धल्ङ्यादिलोपेनैव भाव्यम्॥ अत्र व्याचक्षते—संयोगस्य योऽन्तः सकारस्तस्य लोपः स च हल्ङ्याब्भ्य इत्यनेनेति॥

(उद्द्योतः) संयोगान्तेति। एवं च निवर्तमानवृक्षशब्दसंबन्धिविभक्तिश्रवणप्रसङ्गरूपो दोषो वारित इति भावः॥ नन्विति। संयोगान्तस्य पदस्येति पाठः। संयोगान्तस्य पदान्तस्येति तु व्याख्यानमसङ्गतमेव, स्कसोरितिसूत्रे द्विशकारको निर्देश इति भाष्यविरोधात्। संयोगसंज्ञासूत्रेऽन्तपदसामर्थ्येन द्विवचनान्तेन समास इति ध्वनयता भाष्यकृता प्रयोजनान्तराभावस्य ध्वनितत्वेन तादृशेऽर्थे मानाभावाच्च। दोषान्तरमप्याह—संयोगान्तलोपस्य चेति। हल्ङ्याब्भ्य इति च। न च तत्र सुतिसीति प्रत्ययैः प्रकृत्याक्षेपात्तस्याप्यप्राप्तिः, तदाक्षेपे मानाभावात् फलाभावाच्चेत्यभिप्रायः॥ केचित्त्वाष्टमिकपदद्विर्वचने भाष्यकृता वक्ष्यमाणया रीत्या पचसिपचसीत्यादेः समुदायस्य पदत्ववदिहापि वृक्षसस्स् इति समुदायस्य पदत्वं वृक्षशब्दे तत्त्वप्रत्यभिज्ञानादन्त्यसकारे सुत्वाच्च। ईदृशविषये संयोगादिलोपसंयोगान्तलोपयोरविशेषेण भाष्ये संयोगान्तलोप उक्तः। हल्ङ्यादिलोपस्तु हलन्तप्रकृतेः पर इत्यर्थान्नेत्याशयः। प्रत्येकं संयोगसंज्ञेति पक्षे झल्परसंयोगादित्वेन संयोगादिलोपो भाष्योक्तः साधुरेव। तत्र सूत्रे सङ्कीर्तनाभित्य चेदम्। प्रकारान्तरेणास्य दूषयिष्यमाणत्वाच्च तदनाश्रयणं तस्य प्रत्याख्यानाच्चेत्याहुः॥

(दूषणसाधकभाष्यम्)

कुतो नु खल्वेतत् परयोर्वृक्षशब्दयोर्निवृत्तिर्भविष्यति, न पुनः पूर्वयोरिति?॥

(दूषणबाधकभाष्यम्)

तत्रैतत्स्यात्पूर्वनिवृत्तावपि सत्यां संयोगादिलोपेन सिद्धमिति॥

(प्रदीपः) **संयोगादिलोपेनेति।** अत्राप्येकस्य पदस्य संयोगस्यादिर्नास्तीति हल्ङ्यादिलोपमेव संयोगादिलोपं प्रतिपन्नाः। संयोगश्चासौ प्रत्येकं हलां संयोगसंज्ञेति पक्षाश्रये, आदिश्च वृक्षशब्दापेक्षया तस्य लोपो हल्ङ्याबित्यनेनेत्यर्थः॥

(दूषणसाधकभाष्यम्)

न सिध्यति। तत्रावरतो द्वयोस्सकारयोः श्रवणं प्रसज्येत॥

(प्रदीपः) अवरत इति । स् वृक्षस् इति प्राप्नोति । दुष्टस्प्रतिपादनपरं चैतत्, न पुनः कदाचित्त्रयाणां श्रवणप्रतिपादनार्थम् ॥

(दूषणान्तरभाष्यम्)

यत्र च संयोगान्तलोपो नास्ति, तत्र च न सिध्यति ॥

क्व च संयोगान्तलोपो नास्ति ? ॥

द्विवचनबहुवचनयोः ॥

(प्रदीप) द्विवचनबहुवचनयोरिति । ये स्वभावादेव द्विवचनबहुवचनान्ताः प्रयुज्यन्ते गोदौ दाराः सिकता इत्यादयः तत्र द्विवचनबहुवचनेषु परत एकशेषे सति द्विवचनबहुवचनानां श्रवणप्रसङ्गः । कृतैकशेषाणां वा पुनरेकशेषे क्रियमाणे द्विवचनबहुवचनश्रवणप्रसङ्गः ॥

(उद्द्योतः) नन्वेकशेषं विना कथं द्विवचनादेः सम्भवोत आह—स्वभावादिति । कृतैकशेषाणां वेति । इदं च हलन्ताभिप्रायं तत्र हि हल्ङ्यादिलोपे प्रत्ययलक्षणेन विभक्तिपरतयैकशेषे द्विवचनादौ पुनरेकशेष इत्यर्थः ॥

(इति प्रथमपक्षदूषणनिरूपणम्)

(पक्षान्तरभाष्यम्)

यदि पुनः समास एकशेष उच्यते ॥

(उद्द्योतः) भाष्ये यदि पुनः समासेति । द्वन्द्वे इत्यनुवर्त्यं तत्र कृते इति व्याख्यानात्तस्य निमित्ततया नासौ द्वन्द्वबाधकः । द्वन्द्वे कृते एकविभक्तौ परतः सरूपाणामेकशेष इत्यर्थः । अत्र पक्षे संख्यावाच्येवैकशब्दः ॥

(आक्षेपभाष्यम्)

किं कृतं भवति ? ।

(प्रयोजनभाष्यम्)

कश्चिद्वचनलोपः परिहृतो भवति ॥

(प्रदीपः) कश्चिद्वचनलोप इति । यस्त्वया कश्चिद्वचनलोप उक्तः स परिहृतः । अथ वा सुपां परिहृतो न तिङामित्यर्थः ॥

(उद्द्योतः) समासान्तर्गतसर्ववचनलोपात् कश्चिदित्ययुक्तमत आह—यस्त्वयेति । यस्त्वया वचनलोपासिद्धिरूपः कश्चिद्दोष उक्तः स परिहृत इत्यर्थ इति भावः ॥ अत्राध्याहारगौरवमाशङ्क्याह—अथ वेति ।

(आक्षेपभाष्यम्)

तर्हि समासग्रहणं कर्तव्यम् ॥

(आक्षेपबाधकभाष्यम्)

न कर्तव्यम् । प्रकृतमनुवर्तते ॥ क्व प्रकृतम् ? । "तिष्यपुनर्वस्वोर्नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनं नित्यम्" इति ॥

(७२७ दूषणवार्तिकम् ॥ ५ ॥)

॥ * ॥ समास इति चेत्स्वरसमासान्तेषु दोषः ॥ * ॥

(भाष्यम्) समास इति चेत्स्वरसमासान्तेषु दोषो भवति ॥ स्वर—अश्वश्चाश्वश्च अश्वौ । समासान्तोदात्तत्वे कृते एकशेषः प्राप्नोति ॥ इदमिह संप्रधार्यम्—समासान्तोदात्तत्वं क्रियतामेकशेषः—इति, किमत्र कर्तव्यम् ? । परत्वात्समासान्तोदात्तत्वम् । समासान्तोदात्तत्वे च दोषो भवति । स्वर ॥ समासान्त—ऋक्च ऋक्च ऋचौ । समासान्ते कृते असारूप्यादेकशेषो न प्राप्नोति ॥ इदमिह संप्रधार्यम्—समासान्तः क्रियतामेकशेषः—इति । किमत्र कर्तव्यम् ? । परत्वात्समासान्तः । समासान्ते च दोषो भवति ॥

(प्रदीपः) स्वरसमासान्तेष्विति । समासे कृते समासान्तोदात्तत्वे च यदि पूर्वशेषस्तदा सर्वानुदात्तत्वं प्राप्नोति । अथ परशेषस्तदाश्वशब्दस्यान्तोदात्तत्वप्रसङ्गः ॥ परत्वादिति । ननु नाप्राप्ते समासान्तोदात्तत्वे आरभ्यमाण एकशेषस्तस्य बाधकः । नैतदस्ति । निरवकाशो हि बाधको भवति । कृते च समासान्तोदात्तत्वे एकशेषस्य प्रवर्तनाद्विरोधाभावाच्च नास्त्युत्सर्गापवादभावः ॥ ऋक्चेति । ऋच् ऋच् अ इति स्थिते अन्तर्वर्तिन्या विभक्तेर्लुका लुप्तत्वात् प्रत्ययलक्षणप्रतिषेधान्नास्त्येकविभक्तिपरतेति एकशेषनिमित्तं समुदायाद्विभक्तिरुत्पाद्या । तस्यां च नास्ति सारूप्यम् । एको हि ऋक्शब्दः अपर ऋचशब्दः । समासान्तः समासस्यैवावयवो नोत्तरपदस्येति चेत्तर्हि तेनैव व्यवधानात् समासविभक्तेरेकशेषो न स्यात् । समासार्थस्योत्तरपदस्यान्ताः समासान्ता इत्यपि भाष्यकारस्य मतमिति ऋगृचशब्दयोर्वैरूप्यमाश्रित्य भाष्यकृता दोष उद्भावितः ॥

(उद्द्योतः) समासान्तोदात्तत्वे च कृते इति । विभक्तिसापेक्षैकशेषापेक्षयान्तरङ्गत्वादिति भावः ॥ प्रसङ्ग इति । इष्यते त्वाद्युदात्तत्वमिति भावः । अश्वशब्दस्य क्वनन्तत्वात् ॥ परत्वादित्यस्योत्कृष्टत्वात्पूर्वकालप्राप्तत्वादित्यर्थः । एकशेषस्तु समासाद्विभक्त्युत्पत्त्युत्तरमिति भावः ॥ एवमग्रेपि । एवं चापवादत्वाशङ्का चिन्त्यैव । ब्राह्मणेभ्यो दधीत्यादावविरोधेपि दधिदानतः पूर्वं परत्र वा सावकाशत्वेपि बाधकत्वदर्शनात्समाधिरपि चिन्त्यः ॥ भाष्ये—असारूप्यादिति । समासान्तप्राग्भागस्य विभक्तिपरत्वाभावः, तद्विशिष्टस्य तु न सरूपत्वम् ॥ एकशेषो न स्यादिति । किं चैकशेषे सत्यपि ऋचाविल्यस्यासिद्धिरेव, ऋचे इत्येवमापत्तेः । ऋगृचशब्दयोरेकशेषे तु पक्षे तत्सिद्धिरस्तीति बोध्यम् ॥ उत्तरपदस्यान्ता इति । अयं पक्षस्तु निर्मूल एवेति पञ्चमषष्ठयोर्वक्ष्यामः । गोस्त्रियोरित्यत्रोक्तं च ॥ भाष्यकारस्य मतमिति । एवंविधं

भाष्यं न दृश्यते इति चिन्त्यमिदम् । न चेदं भाष्यमेव तथान्यथैकस्यार्थवत्त्वेनापरस्यानर्थकत्वेन कथमेकशेष इति वाच्यम् । द्वन्द्वावयवानामर्थवतामेवैकशेष इत्यर्थे मानाभावात् । विशिष्टरूपोपादानविषयाया अर्थवत्परिभाषाया इहाप्राप्तेः ॥

(७२८ दूषणवार्तिकम् ॥ ६ ॥)

॥ * ॥ अङ्गाश्रये चैकशेषवचनम् ॥ * ॥

(भाष्यम्) **अङ्गाश्रये च कार्ये एकशेषो वक्तव्यः ॥ स्वसा च स्वसारौ च स्वसारः ॥ अङ्गाश्रये कृतेऽसारूप्यादेकशेषो न प्राप्नोति ॥ इदमिह संप्रधार्यमङ्गाश्रयं क्रियतामेकशेष इति । किमत्र कर्तव्यम् । परत्वादङ्गाश्रयम् ॥**

(प्रदीपः) **अङ्गाश्रये चेति** ॥ चशब्दादनङ्गाश्रयेऽपि । यथा नौश्च नावौ चेति ॥ **स्वसा च स्वसारौ चेति** । किमर्थमेकमेकवचनान्तम्, द्वितीयं तु द्विवचनान्तमिति चेत्, सर्वथा वैरूप्यप्रतिपादनाय । तथा हि । यद्यन्तर्वर्तिन्यां विभक्तौ लुप्तायामपि वचनसामर्थ्यात् प्रत्ययलक्षणमाश्रीयते तदात्र वैरूप्यम् । अथापि समासविभक्त्यैव विभक्तिपरत्वं तथापि वैरूप्यम् ॥

(उद्द्योतः) **सर्वथेति** । समासविभक्तावन्तर्वर्तिविभक्तौ चेत्यर्थः ॥ तदेवाह—**यद्यन्तरिति** । तच्च विग्रहप्रदर्शनेन स्पष्टमेवोक्तम् ॥ **वचनसामर्थ्यादिति** । लुका लुप्तत्वादिति भावः ॥ **अथापीति** । द्वन्द्वे सुब्लुक्यौत्तरपदिकानङि ततो विभक्तावृतोऽङीति गुणेऽप्तृन्निति दीर्घे च परत्वात्कृत इति भावः ॥ एकवचनान्तेन विग्रहे तु समासविभक्ताविव वैरूप्यमन्तर्वर्तिन्यां तु नेति तात्पर्यम् ॥

(७२९ दूषणवार्तिकम् ॥ ७ ॥)

॥ * ॥ तिङ्समासे तिङ्समासवचनम् ॥ * ॥

(भाष्यम्) **तिङ्समासे तिङ्समासो वक्तव्यः ॥**

(प्रदीपः) **तिङ्समास इति** । समास एकशेषे विधीयमाने तिङ्समासेऽप्येकशेषो वक्तव्यः ॥ स च तिङ्समासो वक्तव्य इत्यर्थः ॥

(उद्द्योतः) **समासएकशेषे इति** । प्रत्ययार्थशब्दनिवेशे एकपचा एका क्रियोच्यते एकेन च तिपैकः कर्तेत्यनेकक्रियाकर्तृविवक्षायामनेकतिङन्तप्रसङ्ग एकशेष इष्यते, स च तेषां समासाभावान्न प्राप्नोतीति सरूपतिङन्तानामपि द्वन्द्वो वाच्य इत्यर्थः ॥

(आक्षेपभाष्यम्)

एकं तिङ्ग्रहणमनर्थकम्—'समासे तिङ्समास—' इत्येव सिद्धम् ॥

(प्रदीपः) **एकमिति** । विनापि तेनार्थस्यावगमात् ॥

(आक्षेपबाधकभाष्यम्)

नानर्थकम् । तिङ्समासे प्रकृते तिङ्समासो वक्तव्यः ॥

(प्रदीपः) **प्रकृत इति । आख्यातमाख्यातेनेत्यत्र द्वन्द्वश्च सरूपाणामिति वक्तव्यम् ॥**

(७३० दूषणवार्तिकम् ॥ ८ ॥)

॥ * ॥ तिङ्विधिप्रतिषेधश्च ॥ * ॥

(भाष्यम्) **तिङ् च कश्चिद्विधेयः कश्चित्प्रतिषेध्यः । पचति च पचति च पचतः तश्शब्दो विधेयः, तिशब्दः प्रतिषेध्यः ॥**

(उद्द्योतः) आद्ययोस्तिङोर्लोपेऽपि समासस्याधातुत्वात्ततस्तिङोऽप्राप्तेराह—**भाष्ये तिङ्विधिरिति** ॥ सुब्ग्रहणात्तिङो लुगप्राप्तेराह—**प्रतिषेधश्चेति** । प्रतिषेधोऽत्र लोपः । उपलक्षणमिदं, पादौ पादा इत्यादावेकवद्भावस्यापि प्रसङ्ग इत्यपि बोध्यम् ॥

(इति समस्तैकशेषरूपद्वितीयपक्षदूषणनिरूपणम्)

(असमस्तैकशेषपक्षदूषणप्रकरणभाष्यम्)

यदि पुनरसमास एकशेष उच्येत ।

(प्रदीपः) **यदि पुनरिति** । दोषान्तराभिधानाय पुनरुपन्यासः ॥

(उद्द्योतः) **पुनरुपन्यास इति** । द्वितीयपक्षस्येति शेषः ॥

(७३१ दूषणवार्तिकम् ॥ ९ ॥)

॥ * ॥ असमासे वचनलोपः ॥ * ॥

(भाष्यम्) **यद्यसमासे वचनलोपो वक्तव्यः ॥**

(पुनरुक्तिदोषभाष्यम्)

ननु चोत्पत्तैव वचनलोपं चोदिताः स्मः ॥

(उद्द्योतः) भाष्ये—**उत्पत्तैव** तत्पक्षदूषणमुपक्रमतैव । *पृथग् विभक्त्युपलब्धिस्तदाश्रयत्वात् *इत्यनेन चोदिताः स्म इत्यर्थः ॥

(पुनरुक्तिपरिहारभाष्यम्)

द्विवचनबहुवचनविधिं द्वन्द्वप्रतिषेधं च वक्ष्यति, तदर्थं पुनश्चोद्यते ॥

(प्रदीपः) **तदर्थमिति** । पूर्वं दोषमात्रमुपन्यस्तं केवलाया विभक्तेः श्रवणं प्राप्नोतीति । इदानीं तु तत्प्रतिविधानाय वचने क्रियमाणे गौरवमापद्यत इत्येतत्प्रतिपाद्यते ॥

(उद्द्योतः) दूषणान्तरं वक्तुमुक्तानुवाद इत्याह—**द्विवचनेत्यादि** ॥ **वक्ष्यतीति** । वार्तिककृदिति शेषः ॥ **तदर्थं** तदवतारणार्थम् ॥ **पुनश्चोद्यत इति** ॥ * असमासे वचनलोपः * इत्येतदित्यर्थः ॥

(७३२ दूषणवार्तिकम् ॥ १० ॥)

॥ * ॥ द्विवचनबहुवचनविधिः ॥ * ॥

(भाष्यम्) द्विवचनबहुवचनानि विधेयानि। वृक्षश्च वृक्षश्च वृक्षौ। वृक्षश्च वृक्षश्च वृक्षश्च वृक्षा इति।

(उद्योतः) वक्ष्यतीति यदुक्तं, तदाह—द्विवचनेति। केवलं सोः श्रवणमेव न दोषोऽपि तु द्विवचनाद्यसिद्धिरपि। वचनाद्विभक्तिलोपे कृतेपि प्रत्ययलक्षणेनाप्रत्यय इति निषेधात्प्रातिपदिकत्वाभावेन द्विवचनाद्यनापत्तेस्तदर्थं वचनारम्भे गौरवं च। न ङिसंबुद्ध्योरिति ज्ञापकं च नलोपविषयमेवेत्यर्थः॥

(७३३ दूषणवार्तिकम् ॥ ११ ॥)

॥ * ॥ द्वन्द्वप्रतिषेधश्च ॥ * ॥

(भाष्यम्) द्वन्द्वस्य च प्रतिषेधो वक्तव्यः। वृक्षश्च वृक्षश्च वृक्षौ, वृक्षश्च वृक्षश्च वृक्षश्च वृक्षा इति। "चार्थे द्वन्द्वः" इति द्वन्द्वः प्राप्नोति॥

(उद्योतः) भाष्ये ज्ञापकस्य सामान्यापेक्षत्वेपि दोषमाह—द्वन्द्वप्रतिषेधश्चेति। द्वन्द्वस्य वैकल्पिकत्वात्तदभावेऽस्य सार्थक्यं मन्यते॥

(दूषणपरिहारभाष्यम्)

नैष दोषः। अनवकाश एकशेषो द्वन्द्वं बाधिष्यते।

(उद्योतः) अनवकाश इति। सहविवक्षायां व्यपेक्षाभावे ह्येकशेषस्तत्र च द्वन्द्वस्य नित्यता॥ विशेषणविशेष्यभावानापन्नस्यानेकस्य युगपदेकपदार्थसंबन्धबोधनेच्छा सहविवक्षेति भावः॥

(परिहारदूषणभाष्यम्)

सावकाश एकशेषः॥ कोवकाशः?। तिङन्तान्यवकाशः॥

(प्रदीपः) तिङन्तान्यवकाश इति। कारकभेदात् क्रियाभेदादनेकतिङन्तप्रसङ्गे एकशेषो विधेयः। ततश्च परत्वात्सरूपाणामेकशेषं बाधित्वा द्वन्द्वः प्राप्नोति। सकृद्गतौ विप्रतिषेध इति पुनरेकशेषो न प्राप्नोति। सत्यपि वा पुनःप्रसङ्गविज्ञाने स्वरसमासान्तेषु दोष एव॥

(उद्योतः) कारकभेदादिति। नहि तत्र द्वन्द्वप्राप्तिः सुबन्तानां तद्विधानादिदमवकाशमात्रं, न त्वत्रैकशेषेणेष्टसिद्धिः॥

(इति तृतीयपक्षदूषणनिरूपणम्)

(अथ विभक्त्यन्तैकशेषरूपचतुर्थपक्षनिरूपणभाष्यम्)

यदि पुनः पृथक्सर्वेषां विभक्त्यन्तानामेकशेष उच्येत॥ किं कृतं भवति?॥ कश्चिद्वचनलोपः परिहृतो भवति॥ विभक्त्यन्तानामेकशेषे विभक्त्यन्तानामेव तु निवृत्तिर्भवति॥

(प्रदीपः) यदि पुनरिति। सप्तमीनिर्देशे प्रकृतिमात्रनिवृत्तौ प्रत्ययश्रवणप्रसङ्गः। षष्ठीनिर्देशे तु विभक्त्यन्तानां निवृत्त्या भाव्यमिति नास्ति केवलविभक्तिश्रवणप्रसङ्गः॥ कश्चिदिति। शिष्यमाणस्य त्वेकवचनश्रवणप्रसङ्ग एव॥

(उद्योतः) भाष्ये—यदि पुनरिति॥ चतुर्थः पक्षः॥ षष्ठ्यर्थे सप्तमीति भावः तदाह—षष्ठीनिर्देशे त्विति॥ षष्ठ्यर्थकत्वेन निर्देशे त्वित्यर्थः॥

(७३४ दूषणवार्तिकम् ॥ १२ ॥)

॥ * ॥ एकविभक्त्यन्तानामिति तु पृथग्विभक्तिप्रतिषेधार्थम् ॥ * ॥

(भाष्यम्) एकविभक्त्यन्तानामिति तु वक्तव्यम्। किं प्रयोजनम्?। पृथग्विभक्तिप्रतिषेधार्थं पृथग्विभक्त्यन्तानां मा भूत्। ब्राह्मणाभ्यां च देहि ब्राह्मणाभ्यां च कृतम्॥

(प्रदीपः) एकविभक्त्यन्तानामिति। सप्तमीनिर्देशमपास्य षष्ठीनिर्देशः कर्तव्य इत्यर्थः॥ किं प्रयोजनमिति। एकग्रहणस्य प्रयोजनप्रश्नः। षष्ठीनिर्देशस्य तु प्रयोजनमुक्तमेव कश्चिद्वचनलोपः परिहृत इति॥

(उद्योतः) भाष्ये—एकविभक्त्यन्तानामिति त्विति। एकग्रहणं कर्तव्यं भवतीत्यर्थः। प्रयोजनप्रश्ने तस्यैवोत्तरदानात्॥

(७३५ दूषणनिराकरणवार्तिकम् ॥ १३ ॥)

॥ * ॥ न वार्थविप्रतिषेधाद्युगपद्वचनाभावः ॥ * ॥

(भाष्यम्) न वा एष दोषः॥ किं कारणम्?। अर्थविप्रतिषेधात्। विप्रतिषिद्धावेतावर्थौ कर्ता संप्रदानमिति अशक्यौ युगपन्निर्देष्टुम्। तयोर्विप्रतिषिद्धत्वाद् युगपद्वचनं न भविष्यति॥

(प्रदीपः) न वेति। एकविभक्त्यन्तानामिति न वक्तव्यमेव प्रयोजनाभावात्। ततश्चानुत्पन्नायामेव विभक्तौ प्रातिपदिकानामेकशेषे कृते शिष्यमाणस्य निवर्तमानार्थाभिधानाद् द्विवचनबहुवचनसिद्धिः॥ विप्रतिषिद्धाविति। चतुर्थ्यन्तस्य शेषे ब्राह्मणेभ्य इत्युक्ते च कर्तृत्वं न प्रतीयते। तृतीयान्तस्य शेषे ब्राह्मणैरित्युक्ते संप्रदानत्वं न गम्यते। यश्च शब्दोऽनेकार्थप्रत्यायनाय प्रभवति स शिष्यते नान्यः॥

(उद्योतः) न वेति। प्रत्याख्यानमप्येकग्रहणस्यैव॥ एकविभक्त्यन्तानामिति न वक्तव्यमेवेति। नवेति प्रतीकेऽस्यार्थस्योपयोगश्चिन्त्यः॥ यदि पुनः प्रातिपदिकानामिति प्रतीके त्विदं वक्तुं युक्तम्। अयं तर्हि दोष इत्यग्रिमभाष्यस्वारस्येन तावत्पर्यन्तं विभक्त्यन्तानामेकशेष इति पक्षानुवृत्तेरेव लाभेन तथा व्याख्यानस्यानौचित्याच्च॥ विप्रतिषिद्धावेताविति कर्तृसंप्रदानयोरर्थयोर्विरो-

धेन युगपदेकरूपेणैकस्यान्वयाभावेन सहविवक्षाभावादेकशेषाप्राप्तेरेकत्वेन विभक्तिर्न विशेष्येत्यर्थः । कैयटोक्तं ब्राह्मणेभ्य इत्युक्ते इत्यादि तु वचनलोपवचनविधिकरणेप्येकग्रहणवैयर्थ्योपपादकमिति बोध्यम् ॥

(७३६ दोषनिराकरणयुक्त्यन्तरवार्तिकम् ॥ १४ ॥)

॥ * ॥ अनेकार्थाश्रयश्च पुनरेकशेषः [स्तस्मान्नैकशब्दत्वम्] ॥ * ॥

(भाष्यम्) **अनेकमर्थं संप्रत्याययिष्यामीति एकशेष आरभ्यते ॥**

तस्मान्नैकशब्दत्वम् । तस्मादेकशब्दत्वं न भविष्यति ॥

(उद्द्योतः) भाष्ये—अनेकमर्थमित्यस्य युगपदेकरूपेणेत्यादिः ॥

(दूषणभाष्यम्)

अयं तर्हि दोषः—कश्चिद्वचनलोपो द्विवचनबहुवचनविधिर्द्वन्द्वप्रतिषेधश्चेति ।

(प्रदीपः) **अयं तर्हीति** । एकविभक्त्यन्तानामिति क्रियमाणे प्रत्युत दोषः ॥ **कश्चिदिति** । शिष्यमाणस्यैकवचनस्य लोपो वक्तव्यः ॥

(उद्द्योतः) अयं तर्हीति प्रतीके एकविभक्त्यन्तानामिति क्रियमाणे प्रत्युत दोष इति व्याख्यानं भाष्याक्षरस्वरसविरुद्धम् । उक्तदोषाभावेप्ययं दोष इति ह्यर्थस्तदक्षरमर्यादया लभ्यते ॥ द्विवचनेति । शिष्टस्य विभक्त्यन्ततयाऽप्रातिपदिकत्वेन द्विवचनाद्यप्राप्तेः सापि वाच्येत्यर्थः ॥

(इति चतुर्थपक्षदूषणनिरूपणम्)

(अथ पञ्चमपक्षनिरूपणम्)

(भाष्यम्) **यदि पुनः प्रातिपदिकानामेकशेष उच्येत ॥ किं कृतं भवति ? ॥ वचनलोपः परिहृतो भवति ॥**

(प्रदीपः) **यदि पुनरिति** । एकविभक्ताविति न क्रियते ह्रस्वो नपुंसक इत्यतः प्रातिपदिकग्रहणमनुवर्त्यानुत्पन्नायामेव विभक्तौ सरूपाणां प्रातिपदिकानामेकशेषः क्रियते ॥ तिङन्तेषु कथम् ? । उच्यते । लावस्थायामेव पच् ल पच् ल इति स्थिते कृदन्तत्वात् प्रातिपदिकत्वे सत्येकशेषः ॥

(उद्द्योतः) द्वितीयपक्षाद्विशेषं दर्शयितुमाह—एकेति । प्रातिपदिकानामिति । अनुवृत्तस्य बहुवचनेन विपरिणाम इत्यर्थः । यद्यपि विभक्त्युत्पत्तेः पूर्वं सरूपाणामेकशेष इत्यर्थे भाष्यतात्पर्येण प्रातिपदिकग्रहणानुवृत्तेः फलं चिन्त्यम्, तथापि * हरितहरिणेत्याद्यग्रिमवार्त्तिकोत्थानाय तथोक्तम् ॥ कृदन्तत्वादिति । अतिङिति प्रतिषेधस्तु तिङ एव स्थानिवत्त्वप्राप्तकृत्त्वस्येत्यभिमानः ॥

(७३७ दूषणवार्तिकम् ॥ १५ ॥)

॥ * ॥ प्रातिपदिकानामेकशेषे मातृमात्रोः प्रतिषेधः सरूपत्वात् ॥ * ॥

(भाष्यम्) **प्रातिपदिकानामेकशेषे मातृमात्रोः प्रतिषेधो वक्तव्यः । माता च जनयित्री मातारौ च धान्यस्य मातृमातारः ॥ किं कारणम् ? । सरूपत्वात् । सरूपाणि ह्येतानि प्रातिपदिकानि ॥**

(प्रदीपः) **मातृमात्रोरिति** । कथमयं निर्देशः यावतैकशेषेण भाव्यम् । एकशेषे सति विवक्षितार्थानवगमात् तदभावः । अयं ह्यत्रार्थो विवक्षितः जननीवाचिनः परिच्छेत्तृवाचिनश्च मातृशब्दस्यैकशेषप्रतिषेधो वक्तव्य इति । एष चार्थो मात्रोरित्युक्ते न गम्यते ॥

(उद्द्योतः) भाष्ये—मातृमात्रोरिति । प्रातिपदिकयोरनयोः सारूप्यादिति भावः । इदं पात्रादीनामुपलक्षणम् ॥ यावतैकशेषेणेति । जनन्यादिवाचकयोर्निषेधेपि शब्दपरयोर्निषेधे मानाभाव इत्यर्थः ॥ तदभाव इति । विवक्षितार्थावगमायैकशेषो न कृत इति भावः । एवमेव यत्तदेतेभ्य इत्यादौ कोशेषु चैकशेषाकरणम् ॥

(आक्षेपभाष्यम्)

किमुच्यते प्रातिपदिकानामेकशेषे मातृमात्रोः प्रतिषेधो वक्तव्य इति, न पुनर्यस्यापि विभक्त्यन्तानामेकशेषस्तेनापि मातृमात्रोः प्रतिषेधो वक्तव्यः स्यात् । तस्यापि ह्येतानि क्वचिद्विभक्त्यन्तानि सरूपाणि मातृभ्यां च मातृभ्यां चेति ? ।

(दूषणाशयभाष्यम्)

अथ मतमेतद्विभक्त्यन्तानां सारूप्ये भवितव्यमेवैकशेषेणेति । प्रातिपदिकानामेवैकशेषे दोषो भवति । एवं च कृत्वा चोद्यते ॥

(प्रदीपः) **अथ मतमेतदिति** । अर्थविप्रतिषेधादत्रैकशेषो न भवति । कृते ह्येकशेषे ताभिरित्यनुप्रयोगे पुमर्थो न प्रतीयते, तैरिति चोक्ते स्त्र्यर्थानवगतिः । अभ्युपगम्यवादेन त्वेतदुच्यते विभक्त्यन्तानां सारूप्य इति । प्रातिपदिकावस्थायां सर्वदा सारूप्यात् सर्वत्रैकशेषः स्यात् विभक्त्यन्तानां तु सरूपाणामेकशेषे यत्रैव तृतीयादौ विभक्तौ सारूप्यं तत्रैवैकशेषो न प्रथमाद्वितीययोरित्यर्थः ॥

(उद्द्योतः) मतशब्दसूचितास्वरसं स्पष्टयति—अर्थेति ॥ स्त्र्यर्थानवगतिरिति । प्रकरणादिना प्रतीतिसम्भवाच्चिन्त्यमेतत् । एवं च विभक्त्यन्तानामेकशेषे तृतीयान्तादीनामेकशेषो भवत्येव प्रथमाद्वितीययोस्तु नेति मते दोषाभावात् । एकविभक्ताविति पदरहितप्रातिपदिकैकशेषपक्षे एवैष दोष इत्यर्थो भाष्यस्य विभक्तिपदाभावे सरूपाणामेवैकशेष इत्येवंनियमेन प्राप्तेः । प्रतिषेधेन सहविवक्षाविषयैकशेषस्य निषेधे तद्विषये द्वन्द्वः पक्षे वाक्यं च सिध्यति ।

असद्विवक्षाविषयतत्रं तु भवत्येव। मातृभ्यां कृतं देहीति च अक्षा भज्यन्तामित्यादिवत्। **अथ मतमित्येतेनारुचिर्बोधिता**। तद्बीजं तु—सूत्रव्याख्यानपक्षभेदेन लक्ष्यभेदानौचित्यमिति। तस्माद् विभक्त्यन्तानामेकशेषेपि मातृमात्रोः प्रतिषेधो वक्तव्य एवेति गूढतात्पर्यम्। तद्ध्वनयन्नाह—**एवं च कृत्वेति**। एवमङ्गीकृत्य प्रातिपदिकानामेकशेषे एव प्रतिषेधश्चोद्यत इत्यर्थः॥ वस्तुतो विभक्त्यन्तानामेकशेषेपि तद्वक्तव्यमित्यर्थः। अस्य मतस्य भाष्याभिप्रेतत्वे तु **विरूपाणामनेकशेष** इत्यादि प्रागुक्तभाष्यविरोध इति दिक्। तद्ध्वनयन्नाह—**अभ्युपगम्यवादेन त्विति**। **सर्वदेति**। सर्वत्रेत्यर्थकम्॥

(७३८ दूषणवार्तिकम्॥ १६॥)

॥ * ॥ हरितहरिणश्येतश्येनरोहितरोहिणानां स्त्रियामुपसंख्यानम्॥ * ॥

(भाष्यम्) **हरितहरिणश्येतश्येनरोहितरोहिणानां स्त्रियामुपसंख्यानं कर्तव्यम्। हरितस्य स्त्री हरिणी हरिणस्यापि हरिणी हरिणी च हरिणी च हरिण्यौ। श्येतस्य स्त्री श्येनी, श्येनस्यापि स्त्री श्येनी, श्येनी च श्येनी च श्येन्यौ। रोहितस्य स्त्री रोहिणी रोहिणस्यापि रोहिणी रोहिणी च रोहिणी च रोहिण्यौ।**

(प्रदीपः) **हरितेति**। एषां प्रातिपदिकावस्थायां वैरूप्यमित्येकशेषो न प्राप्नोति विभक्तौ तु सारूप्यसद्भावात् सिध्यत्येकशेषः॥ **हरितस्य स्त्रीति**। नानेन पुंयोगः प्रतिपाद्यते तत्र हि ङीषा भाव्यं हरितीति। किं तर्हि? **अयमर्थः** हरितशब्दस्य हरिणी सा च स्त्री॥

(उद्योतः) अत्रैव पक्षे दूषणान्तरमाह—**हरितेति**। **लिङ्ग**विशिष्टपरिभाषामनाश्रित्येदम्॥ **सा च स्त्रीति**। एवं च **वर्णा**दनुदात्तादिति ङीन्नकारौ॥

(७३९ समाधानवार्तिकम्॥ १७॥)

॥ * ॥ न वा पदस्यार्थे प्रयोगात्॥ * ॥

(भाष्यम्) **न वा एष दोषः॥ किं कारणम्?। पदस्यार्थे प्रयोगात्। पदमर्थे प्रयुज्यते। विभक्त्यन्तं च पदम्। रूपं चेहाश्रीयते। रूपनिर्ग्रहश्च शब्दस्य नान्तरेण लौकिकं प्रयोगम्। तस्मिंश्च लौकिके प्रयोगे सरूपाण्येतानि॥**

(प्रदीपः) **न वेति**। प्रातिपदिकग्रहणं विच्छिन्नत्वादिह नानुवर्तते। सारूप्यं चेहाश्रीयते। न च प्रातिपदिकानि लोके प्रयुज्यन्ते। किं तर्हि? पदान्येव। शास्त्रेपि प्रकृत्याद्युपदेशेनानुमेयत्वात्प्रातिपदिकानां प्रयोगाभावः। तेन पदावस्थायां मातृमातार इति वैरूप्यादेकशेषाभावः। हरिण्यावित्यादौ तु भवतीति दोषप्रतिविधानं कृतम्।

(उद्योतः) ननु लौकिके प्रयोगे सरूपत्वेप्येषां प्रातिपदिकत्वाभावात्कथमेकशेषसिद्धिरत आह—**प्रातिपदिकग्रहणमिति**। तदनुवृत्तौ लौकिके प्रयोगे सरूपाणामित्युक्तेऽप्यन्तरङ्गत्वादेकशेषप्रवृत्तिर्विभक्त्युत्पत्तेः पूर्वमेवेति सुप्प्रकृतीनामेवैकशेषसिद्धिरिति भावः। लौकिकप्रयोगश्च येषामेकशेषस्तत्प्रकृतिकविभक्त्यन्त एव प्रत्यासत्तेः। एतेन हरिणीशब्दस्यापि तत्प्रकृतिकतद्धितघटितप्रयोगे वैरूप्यमस्त्येवेति परास्तम्। नन्वन्यत्र **तरप्तमपौ घ** इत्यादौ लौकिकासंभवे शास्त्रीयग्रहणस्योक्तत्वादत्रापि तथैवास्त्वित्यत आह—**शास्त्रेपीति**। लौकिकतादृशप्रयोगत्वावच्छेदेन च सारूप्यं विवक्षितं तदाह—**तेनेत्यादि**॥

(भाष्यम्) **अपर आह—*न वा पदस्यार्थे प्रयोगात्*। न वा एष पक्ष एवास्ति प्रातिपदिकानामेकशेष इति। किं कारणम्?। पदस्यार्थे प्रयोगात्। पदमर्थे प्रयुज्यते विभक्त्यन्तं च पदम्। रूपं चेहाश्रीयते। रूपनिर्ग्रहश्च शब्दस्य नान्तरेण लौकिकं प्रयोगम्। तस्मिंश्च लौकिके प्रयोगे प्रातिपदिकानां प्रयोगो नास्ति॥**

(प्रदीपः) **अपर आहेति**। पक्षासम्भवप्रतिपादनार्थमिदमुक्तमित्यर्थः।

(उद्योतः) **पक्षासंभवेति**। लौकिके प्रयोगे सरूपाणामित्युक्ते प्रातिपदिकैकशेषस्योक्तिसंभव एव न, किं तु विभक्त्यन्तानामेकशेष इति पक्षस्यैवापत्तिरिति भावः॥

(पञ्चमपक्षसमर्थन आक्षेपभाष्यम्)

अथानेन पक्षेणार्थः स्यात्प्रातिपदिकानामेकशेष इति॥

(प्रदीपः) इदानीं भाष्यकार एनं पक्षं समर्थयितुमाह—**अथानेनेति**॥

(उद्योतः) **अथानेनेति**। यद्यनेन पक्षेण प्रयोजनं स्यात् **'तदा सोपि समर्थयितुं शक्यः'** इति शेषः॥

(समाधानभाष्यम्)

बाढमर्थः॥

किं वक्तव्यमेतत्?।

नहि॥

कथमनुच्यमानं गंस्यते?।

एतेनैवाभिहितं सूत्रेण "सरूपाणामेकशेष एकविभक्तौ" इति॥

कथम्?।

विभक्तिः सारूप्येणाश्रीयते। अनैमित्तिक एकशेषः। एकविभक्तौ लौकिके प्रयोगे यानि सरूपाणि तेषामेकशेषो भवति॥

क?।

यत्र वा तत्र वेति।

(प्रदीपः) **विभक्तिः सारूप्येणेति**। एकविभक्तिर्नैकशेषनिमित्तत्वेनेहोपात्ता, किं तर्हि? सारूप्योपलक्षणार्था, एक-

विभक्तौ लौकिके प्रयोगे यानि सरूपाणि दृष्टानि तेषामेकशेषः । स चानैमित्तिकत्वाद्विभक्तिं नापेक्षते ॥ भाष्ये प्रातिपदिकग्रहणस्योपलक्षणार्थत्वाद् ङ्यावन्तादीनामपि हरिण्यादीनामेकशेषो भवति । **स्वरभिन्नानामिति** वचनान्ङीवन्तस्य हरिणीशब्दस्य शेषः ॥ ये त्वाहुर्हरितहरिणयोरेवैकशेषे कृते उभयवाचित्वेप्यन्यतरस्य वर्णवाचित्वं जातिवाचित्वं वाश्रित्य स्त्रीप्रत्ययः क्रियत इति । तेषां पक्षे स्वरभेदप्रसङ्गः । मातृमात्रोस्तु क्वचित्सारूप्येप्यर्थविप्रतिषेधादेकशेषाभावः ॥ **यत्र वेति ।** अनेनानैमित्तिकत्वमेव प्रतिपाद्यते ॥

(उद्द्योतः) पर आह बाढमर्थ इति ॥ स एवाह—**किं वक्तव्यमिति ।** प्रातिपदिकानामेकशेष इति सूत्रं कर्त्तव्यं चेत्यर्थः ॥ **सारूप्येणेति ।** तेन स्वोपलक्षकतया विभक्तिराश्रीयतइति भावः ॥ **ये त्वाहुरिति ।** प्रातिपदिकग्रहणं नोपलक्षणमिति भावः ॥ **हरितहरिणयोरिति ।** विभक्तौ यानि सरूपाणि दृष्टानि तदवयवप्रातिपदिकानामित्यर्थ इति भावः ॥ **अन्यतरस्येति ।** शिष्टस्यान्यतरस्योभयवाचित्वेनेत्यर्थः ॥ **जातिवाचित्वं चेति ।** चकारघटितः पाठः ॥ **क्वचित्सारूप्ये इति ।** वस्तुतस्तु विभक्तित्वावच्छेदेन सारूप्यविवक्षणान्न मातृमात्रादौ दोष इति बोध्यम् । एकशब्दस्वारस्येनैवकारापकर्षणेन वैकस्यामपि विभक्तौ यानि विरूपाणि नेत्यर्थादिति दिक् ॥ एकग्रहणफलं तु चिन्त्यमेव । अत एव **पृथक् सर्वेषां विभक्त्यन्तानामेकशेष** इति पक्षे **एकग्रहणं पृथग्विभक्तिप्रतिषेधार्थमित्युक्तं** तेन हि तदतिरिक्तपक्षेषु तद्वैयर्थ्यं ध्वनितम् । तत्पक्षेपि **न वार्थविप्रतिषेधादिति** तत्प्रत्याख्यातमेव । अत्रापि **विभक्तिः सारूप्येणाश्रीयत इत्येवोक्तं न त्वेकविभक्तिरिति ।** न चैवं नृणां नृणामित्यादावेकशेषानापत्तिः, दीर्घस्य वैकल्पिकत्वेन सारूप्यनियमाभावादिति वाच्यम् । **विरूपाणामपि समानार्थानामिति** सिद्धेः ॥ यत्त्वेकग्रहणसामर्थ्येन यद्विभक्तिविषये एकशेषस्तस्यामेव सारूप्यमित्यर्थात् तृतीयादौ मातृमात्रोरेकशेषसिद्धिरिति । तन्न । वार्तिकारम्भे सर्वत्र प्रतिषेधेन पक्षयोः फलभेदापत्तेरित्यलम् ।

(इति पथमपक्षसमर्थनम्)

—→०←—

(अथ तृतीयपक्षसमर्थनायाक्षेपभाष्यम्)

अथानेन पक्षेणार्थः स्याद् 'विभक्त्यन्तानामेकशेषः' इति ॥

(समाधानभाष्यम्)

बाढमर्थः ॥

किं वक्तव्यमेतत् ? ॥

नहि ॥

कथमनुच्यमानं गंस्यते ? ॥

एतदप्येतेनैवाभिहितं सूत्रेण "सरूपाणामेकशेष एकविभक्तौ" इति ॥

कथम् ? ।

नेदं पारिभाषिक्या विभक्तेर्ग्रहणम् ।

किं तर्हि ? ।

अन्वर्थग्रहणं विभागो विभक्तिरिति । एकविभागे यानि सरूपाणि तेषामेकशेषो भवतीति ॥

(प्रदीपः) **विभाग इति ।** कर्मादिकारकमिह विभक्तिशब्देनोच्यते । तेन हि प्रातिपदिकार्थो विभागेनावस्थाप्यते । तत्रैकस्मिंश्चित् कारके विवक्षिते तन्निमित्तया विभक्त्या भाव्यमित्येकविभक्त्यन्तानां सरूपाणामेकशेषः सिध्यति ॥

(उद्द्योतः) भाष्ये किं **वक्तव्यमिति ।** एकविभक्तीनामिति षष्ठ्यन्तं वक्तव्यं किमित्यर्थः ॥ **तेन हीति ।** बाहुलकात्करणसाधनः कारकशक्तिवाची विभक्तिशब्द आश्रीयत इति भावः ॥ **विवक्षित इति ।** अनेन सूत्रेपि विषयसप्तमीति दर्शितम् । कारकशक्तेः शब्दात्परत्वासंभवादिति बोध्यम् ॥

(प्रथमाक्षेपस्मारणभाष्यम्)

ननु चोक्तम् कश्चिद्वचनलोपो द्विवचनबहुवचनविधिर्द्वन्द्वप्रतिषेधश्च इति ॥

(प्रदीपः) **कश्चिदिति ।** अवस्थितस्य वचनस्य लोपो वक्तव्यः । तस्मिन्नपि कृते प्रत्ययलक्षणेन प्रत्ययान्तत्वात् प्रातिपदिकसंज्ञाया अभावाद् द्विवचनबहुवचने न सिध्यत इति ते अपि वक्तव्ये । **न ङिसंबुद्ध्योरिति** तु ज्ञापकं नलोपविषयमेव । अथाप्यविशेषेण लुप्तप्रत्ययस्य प्रातिपदिकसंज्ञायां ज्ञापकम् । एवमप्येकार्थत्वाच्छिष्यमाणस्य द्विवचनबहुवचनासिद्धिरेव ॥

(उद्द्योतः) **लुप्तप्रत्ययस्येति ।** बहुव्रीहिः ॥ **एकार्थत्वाच्छिष्यमाणस्येति ।** न च शिष्यमाणं लुप्यमानार्थाभिधायीति न्यायविरोधः । प्रत्येकपर्याप्तैकत्वविशिष्टानामेव शिष्यमाणशब्दबोध्यतया द्वित्वादिविशिष्टार्थाप्रतीत्या द्विवचनाद्यसिद्धिरिति भावः ॥

(आक्षेपनिरासभाष्यम्)

नैष दोषः । यत्तावदुच्यते कश्चिद्वचनलोपो द्विवचनबहुवचनविधिः इति ॥

(७४० आक्षेपनिरासहेतुवार्तिकम् ॥ १९ ॥)

॥ * ॥ सहविवक्षायामेकशेषः ॥ * ॥

(भाष्यम्) **युगपद्विवक्षायामेकशेषेण भवितव्यम् ॥**

(प्रदीपः) **सहविवक्षायामिति ।** एवं चैकैकस्यानेकार्थाभिधानाद् द्विवचनबहुवचनान्तानामेवैकशेषः ॥

(उद्द्योतः) **एवं चैकैकस्येति ।** युगपदधिकरणवचनताश्रयेणेति भावः ॥ सर्वेषामर्थानां सर्वैः शब्दैर्युगपद्बोधनेच्छा हि **सहविवक्षेति** तात्पर्यम् ॥

(आक्षेपभाष्यम्)

न तर्हीदानीमिदं भवति—वृक्षश्च वृक्षश्च वृक्षौ, वृक्षश्च वृक्षश्च वृक्षश्च वृक्षा इति ॥

(प्रदीपः) न तर्हीति। नित्येनैकशेषेण भवितव्यमिति वाक्यं न प्राप्नोतीत्यर्थः ॥

(इष्टापत्तिभाष्यम्)

नैतत्सहविवक्षायां भवति ॥ अथापि निदर्शयितुं बुद्धिरेवं निदर्शयितव्यम्—वृक्षौ च वृक्षौ च वृक्षौ, वृक्षाश्च वृक्षाश्च वृक्षाश्च वृक्षा इति।

(प्रदीपः) इतरो भिन्नार्थत्वाद् एकशेषवृत्त्या वाक्यं न बाध्यत इत्याह—नैतदिति। प्रत्येकमत्र विवक्षेत्यर्थः ॥ बालास्तु प्रक्रियावाक्येनैव व्युत्पाद्यन्त इत्याह—अथापीति ॥

(उद्योतः) भिन्नार्थत्वादिति। सर्वेषामर्थानां सर्वैः शब्दैः साहित्येनार्थप्रतिपादनविवक्षाभावादिति भावः ॥ इत्याहेति। इत्याशयेनाहेत्यर्थः ॥ अथापि निदर्शयितुमित्यनेन वक्ष्यमाणस्यासाधुत्वं बोधितम्। यथा चालौकिकविग्रहवाक्येनासाधुनापि समाससंज्ञाप्राप्त्यवस्थानिदर्शनं तथानेनापीत्यर्थः ॥

(द्वितीयाक्षेपनिरासभाष्यम्)

यदप्युच्यते—"द्वन्द्वप्रतिषेधश्च वक्तव्यः" इति ॥ नैष दोषः। अनवकाश एकशेषो द्वन्द्वं बाधिष्यते ॥

(आक्षेपस्मारणभाष्यम्)

ननु चोक्तम्—सावकाश एकशेषः। कोऽवकाशः?। तिङन्तान्यवकाश इति ॥

(आक्षेपनिरासभाष्यम्)

न तिङन्तान्येकशेषारम्भं प्रयोजयन्ति ॥ किं कारणम्?। यथाजातीयकानां द्वितीयस्य पदस्य प्रयोगे सामर्थ्यमस्ति तथाजातीयकानामेकशेषः। न च तिङन्तानां द्वितीयपदस्य प्रयोगे सामर्थ्यमस्ति। किं कारणम्?। एका हि क्रिया। एकोक्तत्वात्तस्यार्थस्य द्वितीयस्य प्रयोगेण न भवितव्यम्—उक्तार्थानामप्रयोग इति।

(प्रदीपः) यथाजातीयकानामिति। द्रव्यवाचिनामित्यर्थः ॥ एकाहीति। आख्यातवाच्या क्रिया सर्वैव निवृत्तभेदा प्रतीयते। भवद्भिरास्यत इत्यादौ वस्तुस्थित्या कर्तृभेदाद् भेदेपि तिङन्ताद् भेदस्यानवगमात्। प्रकर्षाभ्यावृत्त्यादयस्तु भेदनिबन्धना आश्रयप्रकर्षाभ्यावृत्त्यादिभेदनिमित्ता नैकत्वं क्रियाया विघ्नन्ति ॥

(उद्योतः) द्रव्यवाचिनामिति। सत्त्ववाचिनामित्यर्थः ॥ ननु कर्त्रादिभेदात् क्रियाभेदावगमेनैका क्रियेत्यनुपपन्नमत आह आख्यातेति। शब्दशक्तिस्वभावादिति भावः ॥ सर्वैव सर्वापि ॥ निवृत्तभेदा स्वतो द्वित्वादिसंख्यारहिता भेदस्यतत्सहचरितद्वित्वादेः ॥ स्वगतमेकत्वं तु प्रतीयत इत्येकवचनमिति भावः ॥ प्रकर्षाभ्यावृत्त्यादयस्त्विति। अभ्यावृत्तिरत्र गणनम् ॥ आश्रयाभ्यावृत्तीति। आश्रयप्रकर्षात् प्रकर्षः, अभ्यावृत्तिर्जन्म तद्गणनमेव क्रियागणनमिति भावः ॥ एकत्वं न विघ्नन्तीति। द्वित्वादिप्रतीतौ हि उत्तरया पूर्वसंख्याबाधनात्तद्विहतिः स्यादिति भावः ॥

(आक्षेपभाष्यम्)

यदि तर्ह्येका क्रिया, द्विवचनबहुवचनानि न सिध्यन्ति पचतः पचन्ति ॥

(आक्षेपनिरासभाष्यम्)

नैतानि क्रियापेक्षाणि ॥ किं तर्हि? ॥ साधनापेक्षाणि ॥

(प्रदीपः) नैतानीति। कर्तृकर्मसमवेतसंख्याभिधायिनी द्विवचनबहुवचने इत्यर्थः ॥ ननु कर्तृकर्मणोर्लविधानादनेकस्मिन् कारके अनेकेनैव लकारेणोत्पत्तव्यम्। भवत्वनेको लकारः लकारजातेरव्यवधानात् ॥ लस्येत्यत्र लजात्याश्रयणादनेकस्यापि लस्य स्थाने अर्थत आन्तर्याद् द्विवचनबहुवचने भविष्यत इत्यदोषः ॥

(उद्योतः) कर्तृकर्मेति। अस्यारोपितेत्यादिः ॥ भाष्ये साधनशब्देन तिङन्ताभिधेयकर्तृकर्मगतसंख्याविशेष उच्यते, तदपेक्षाणि तदारोपापेक्षाणि। एवं चैकस्मिन्नेव तदारोपात्र पदभेदप्रसङ्ग इति नैकशेषस्यात्र विषय इति भावः ॥ अनेकेनैवेति। वर्तमाने लडित्यत्र संख्याविवक्षणेपि धातुभेदेन वाक्योपप्लववत् कर्तृरूपार्थभेदेनापि वाक्योपप्लवादनेकप्रसङ्गो दुर्वारः। अत एवाग्रे एकप्रकृतेरनेकयत्नुत्पत्तिं भाष्यकृद्वक्ष्यति ॥ जात्याश्रयणादिति। जात्याश्रयानेकव्यक्त्याश्रयणादित्यर्थः ॥ अर्थत आन्तर्यादिति। द्व्यर्थस्य लद्वयस्य द्विवचनं बह्वर्थस्य लसमुदायस्य बहुवचनमिति भावः ॥ केचित्त्वनेकलकारोत्पत्तौ न मानम् कर्तृत्वारोपवदेकस्मिन्ननेकार्थत्वस्याप्यारोपादित्याहुः ॥ एवं चानवकाशत्वादेकशेषो द्वन्द्वबाधक इति स्थितम् ॥

(अथ प्रथमपक्षाभ्युपगमभाष्यम्)

अथ वा पुनरस्तु "एकविभक्तौ" इति ॥

(उद्योतः) भाष्ये—अथ वा पुनरित्यादिना समुदायादेकविभक्ताविति पक्षः समर्थ्यते ॥

(आक्षेपस्मारणभाष्यम्)

ननु चोक्तम्—*एकविभक्काविति चेन्नाभावाद्विभक्तेः* इति ॥

(आक्षेपनिरासभाष्यम्)

नैष दोषः। परिहृतमेतत् अर्थवत्प्रातिपदिकमिति प्रातिपदिकसंज्ञा भविष्यतीति॥

(आक्षेपस्मारणभाष्यम्)

ननु चोक्तम्—नियमश्च प्राप्नोति अर्थवत्समुदायानां समासग्रहणं नियमार्थम् इति ॥

(आक्षेपनिरासभाष्यम्)

नैष दोषः । तुल्यजातीयस्य नियमः ॥ कश्च तुल्यजातीयः ? । यथाजातीयकानां समासः ॥ कथंजातीयकानां समासः ? । सुबन्तानाम् ॥

(प्रदीपः) **तुल्यजातीयस्येति** । अवयवानां समुदायार्थतन्त्रत्वात्समुदायविभक्त्यैवावयवार्थस्य संख्यावगमात् पृथगवयवेभ्यो विभक्तिर्नोत्पद्यते ॥ विरूपसमुदाये तु सुबन्तानां द्वन्द्ववचनेनायं न्यायो बाध्यते इत्यवयवेभ्य एव विभक्त्युत्पत्तिः ॥ **सुबन्तानामिति** । यद्यपि गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पत्तेरित्युच्यते तथापि पूर्वपदं तत्र सुबन्तमेवेति सोपि तदपेक्षया सुबन्तानामेव समासः । अन्यथा नलोपादीनि पदकार्याणि पूर्वपदे न स्युः । उत्तरपदमेव तु तत्रासुबन्तम् ॥ इह राजन् राजन् औ इति स्थिते परत्वाभित्यत्वाच्चोपधाया दीर्घे कृते वैरूप्यादेकशेषो न प्राप्नोति ॥ उच्यते—विरूपाणामपि समानार्थानामिति भविष्यति अन्तरङ्गत्वाद्वा । दीर्घत्वं हि नान्तरङ्गम् । उपधां विभक्तिविशेषमसंबुद्धिसर्वनामस्थानमपेक्षत इति बहिरङ्गम् ॥

(उद्द्योतः) **समुदायविभक्त्यैवेति** । अवयवारभ्यत्वात्समुदायसंख्यायाः समुदायगतसंख्याभिधायिसमुदायविभक्त्यैवावयवार्थेपि तत्संख्याप्रतीतेर्गतार्थत्वाच्चावयवेभ्यः पृथग् विभक्तिप्रसङ्ग इति भावः ॥ अवयवानां पदत्वादिरूपोपकारस्य समुदायविभक्त्याऽसंभवाच्चिन्त्यमिदम् । किं च विशेष्यविभक्तया विशेषणीयसंख्यादीनामुक्तावपि विशेषणाद्यथा साधुत्वाय विभक्तिः क्रियते तथात्रापि दुर्वारेति । तस्मात्प्रत्येकगतसंख्याया अविवक्षणाच्च प्रत्येकं सुबुत्पत्तिः । समुदायगतबहुत्वसंख्याया एव विवक्षणेन तद्बोधकसमुदायादेव विभक्तिस्तावताप्यपदं न प्रयुञ्जीतेति निषेधातिक्रमाभावादिति भाष्यार्थः ॥ प्रत्येकसंख्याविवक्षाभावे सति बहुत्ववत्त्वेन विवक्षणात् पृथक् प्रयोगार्हत्वमप्येषां नेति भेदसंसर्गद्वारकमर्थवत्त्वमस्य नेति न नियमेन व्यावृत्तिरिति तात्पर्यम् ।

(७४१ आक्षेपवार्तिकम् ॥ २० ॥)

॥ * ॥ सर्वत्रापत्यादिषूपसंख्यानम् ॥ * ॥

(भाष्यम्) **सर्वेषु पक्षेष्वपत्यादिषूपसंख्यानं कर्तव्यम् । भिक्षाणां समूहो भैक्षमिति ॥**

(प्रदीपः) **सर्वत्रेति** । षट्पक्षा इहोपक्षिप्ताः पृथग्विभक्तौ परत एकशेषः, एकवचनान्तानां वा, समासाद्वैकस्यां विभक्तौ परतः, सरूपसमुदायाद्वा विहितायामेकविभक्तौ परतः, प्रातिपदिकानां वा, सहविवक्षायां वा प्रत्येकं द्विवचनबहुवचनान्तानामिति । तत्र पश्चिमं पक्षत्रयमङ्गीकृतम् । तत्र भिक्षा भिक्षा भिक्षा आम् अ इति स्थिते सर्वविधिभ्यो लुग्विधेर्बलवत्त्वाद् लुकि कृते विभक्त्यभावादेकविभक्तौ परतो विधीयमान एकशेषो न प्राप्नोति, प्रत्ययलक्षणं च नास्ति न लुमताङ्गस्येति प्रतिषेधात् । प्रातिपदिकैकशेषपक्षे समर्थं यद् ङ्याप्प्रातिपदिकं तस्मात्तद्धिता इत्याबन्तादणि कृते परत्वादादिवृद्धौ कृतायां वैरूप्यादेकशेषाप्रसङ्गः । यदा तु सहविवक्षायां विभक्त्यन्तानामेकशेषः सुबन्ताच्च तद्धित इत्ययं पक्षस्तदा सुबन्तसमुदायात्तद्धिताभावात्पूर्वमेकशेषः पश्चात्तद्धित इति न कश्चिद्दोषः ॥

(उद्द्योतः) तत्र सरूपसमुदायादेकविभक्तावेकशेषपक्षे दोषमुपपादयति—**तत्र भिक्षेति** । पदस्य विभज्यान्वाख्यानपक्षे इदम् । आबन्तसमुदायस्य चाप्रत्ययान्तत्वात्प्रातिपदिकत्वमिति भावः । **स्त्रीप्रत्यये चानुपसर्जनेनेति** तु स्त्रीप्रत्ययत्वेन तद्व्याप्यधर्मेण वा स्त्रीप्रत्ययग्रहणे इति तात्पर्यम् ॥ **तदा सुबन्तसमुदायादिति** । तस्य सुबन्तत्वपर्याप्त्यधिकरणत्वाभावादिति भावः ॥ एवं च भाष्ये सर्वत्रशब्देन पक्षद्वयमेव ग्राह्यमिति तात्पर्यम् ॥ वस्तुतस्तु तद्व्यवादेकस्मात्तस्य दुर्वारत्वेन तत्र कृते परत्वादादिवृद्धौ वैरूप्यात्तत्पक्षेप्येकशेषो न प्राप्नोति । न च विनिगमनाविरहेण प्रत्येकमुत्पत्तावण्त्रयापत्तिस्तावतापि अ अभैक्षमित्यस्याप्यापत्त्या नियतभैक्षासिद्धेस्तदवस्थत्वात् ॥ किं च प्रातिपदिकानां चैकशेषे सिद्धमिति भाष्ये न्यूनता, प्रत्येकं द्विवचनाद्यन्तानामेकशेष इति पक्षेपि त्वदुक्तरीत्या दोषाभावात् । युगपदधिकरणवचनतायां दुःखस्वदुरुपपादत्वयोर्द्वितीये भाष्ये वक्ष्यमाणतया तत्पक्षोक्तिसंभवाभावाच्च । समर्थग्रहणेन तु न विभक्तिनिमित्तकार्यस्य पूर्वं प्रवृत्तिः । निर्श्चाह आगतं त्रिश्वाद्रूप्यमित्यादेर्विभाषा पूर्वाह्णेति सूत्रभाष्यस्यासंगत्यापत्तेरित्याहुः ॥ प्रातिपदिकैकशेषपक्षे मातृमात्रादौ यथा नैकशेषस्तथोक्तमेव ॥

(वार्तिके सर्वत्रपदासंगतिभाष्यम्)

सर्वत्रेत्युच्यते प्रातिपदिकानां चैकशेषे सिद्धम् ।

(प्रदीपः) **प्रातिपदिकानां चेति** । अनैमित्तिकत्वादन्तरङ्गत्वात् पूर्वमेकशेषः पश्चाद्वृद्धिः । अथ वा तद्धित एव पश्चादुत्पद्यत इति भावः ॥

(उद्द्योतः) भाष्ये **सिद्धमिति** । सुबन्तात्तद्धितोत्पत्त्या तत्पक्षे एकशेषस्यान्तरङ्गत्वात् । एवं च सर्वत्रेत्यसंगतमिति भावः ॥

(सर्वत्रपदासंगतिनिरासभाष्यम्)

अपत्यादिष्विद्युच्यते बहवश्चापत्यादयः । गर्गस्यापत्यं बहवो गर्गाः । एका प्रकृतिर्बहवश्च यञः । असारूप्यादेकशेषो न प्राप्नोति ॥

(प्रदीपः) **बहवश्च यञ इति** । प्रत्यर्थं शब्दनिवेशाच्च बहुष्वपत्येषु बहवो यञ उत्पाद्याः । तत्र गर्ग य य य इति स्थिते समुदायस्य तद्धितान्तत्वात् प्रातिपदिकत्वात्तत एका विभक्तिस्तत्र प्रथमस्य यशब्दस्य प्रकृतिसन्निपातकृतं वैरूप्यमित्येकशेषो न प्राप्नोति ॥ ननु प्रकृतिं विहाय यशब्दानां सारूप्यादेकशेषो विधास्यते । नैतदस्ति । विभक्त्युत्पत्तावभ्यन्तरीकृता

प्रकृतिर्विभक्तिलक्षितसारूप्याश्रये एकशेषे कथं हातुं शक्यते। न च यञां प्रकृत्यर्थानपेक्षः समुदायार्थः तत्कथं प्रकृतिर्वर्ज्येत। यदापि सहविवक्षायां विभक्त्यन्तानामेकशेष इति पक्षः तदा गर्ग य अस् य अस् य अस् इति स्थिते पूर्वस्य य अस्शब्दस्य प्रकृतिसन्निपाताद्वैरूप्यम्, प्रातिपदिकैकशेपपक्षेपि तथैव वैरूप्यमित्येकशेषो न प्राप्नोति॥

(उद्योतः) इदानीं तस्य सार्थक्यं दर्शयितुमपत्यार्थ एव पक्षत्रयेपि दूषणमाह—अपत्यादिष्विति। एका प्रकृतिरिति। अर्थाभेदादभिन्नेवेत्यर्थः॥ तद्धितान्तत्वादिति। अन्त्ययशब्दस्यापि गर्गाद् विहितत्वेन समुदायस्य तदादितदन्तत्वादिति भावः॥ प्रकृतिसंनिपातेति। तत्र प्रथमस्य सान्निध्यात्सन्निपातोऽन्ययोस्तु व्यवहितत्वान्नास्तीति वैरूप्यमिति भावः॥ अभ्यन्तरीति। गर्गयशब्दविशिष्टयशब्दद्वयस्य प्रातिपदिकत्वे तदर्थगतसंख्याभिधायितया प्रवृत्ता विभक्तिः सारूप्योपलक्षणतायां प्रकृतिं न त्यजतीत्यर्थः॥ न च यञामिति। यञ्समुदायस्येत्यर्थः॥ समुदायार्थः। अपत्यसमुदायरूपोर्थः॥ अपत्याद्यर्थस्य ससंबन्धिकत्वादिति भावः॥ तदा गर्ग येति प्रत्येकं तद्धितान्तत्वात्सहविवक्षायां बह्वर्थत्वाच्च प्रत्येकं बहुवचनमिति भावः॥

(आक्षेपबाधकभाष्यम्)

ननु च यथैव बहवो यञः, एवं प्रकृतयोपि बह्व्यः स्युः॥

(प्रदीपः) **एवं प्रकृतयोपीति।** एकैकस्यापत्यस्य प्रकृत्यर्थेन योगात् प्रधानभेदे च गुणाभ्यावृत्त्या गार्ग्यशब्दानामेवैकशेषः क्रियत इत्यर्थः॥

(उद्योतः) **प्रधानभेदे च गुणाभ्यावृत्त्येति।** प्रातिपदिकोद्देशेन तद्विधानात् प्रातिपदिकार्थस्य तत्र विशेषणत्वाद्गुणता। किं चैकस्मादनेकेषां परत्वासंभव इति भावः॥

(आक्षेपसाधकभाष्यम्)

नैवं शक्यम्। इह हि दोषः स्याद्—गर्गा वत्सा विदा उर्वा इति। अञ्यो बहुषु यञ्यो बहुष्वित्युच्यमानो लुङ् प्राप्नोति॥

(प्रदीपः) **अञ् यो बहुष्विति।** यदा यञामेवैकशेषः क्रियते, तदा शिष्यमाणो यशब्दो बहुषु वर्तत इति लुक् सिध्यति। गार्ग्यशब्दानां त्वेकशेषे यशब्दो बहुषु न वर्तते किं तर्हि, यशब्दान्त इति लुङ् न सिध्यति॥

(उद्योतः) **अञ् यो बहुष्विति** भाष्ये। **तेनैवे**त्यनुवृत्त्या प्रत्ययस्यैव बहुषु वृत्तेर्लुगभ्युपगम इति भावः॥ **यदा यञामेवेति।** उक्तरीत्याऽस्योपपत्तिश्चिन्त्या। लुक्शास्त्रवैयर्थ्योपादनमेवात्र भाष्यकृत्तात्पर्यविषयीभूतम्॥

(समाधानभाष्यम्)

मा भूदेवम्। अञन्तं यद्बहुषु, यञन्तं यद्बहुष्वित्येवं भविष्यति॥

(प्रदीपः) **अञन्तं यदिति।** तेनैव चेत् कृतं बहुत्वमित्यपि तदन्तेनेति व्याख्यायते॥

(आक्षेपसारणभाष्यम्)

ननु चोक्तम्—नैवं शक्यमिह हि दोषः स्यात्—काश्यपप्रतिकृतयः काश्यपा इति॥

(प्रदीपः) **काश्यपा इति।** एकस्मिन् कश्यपापत्येऽभिकृते तत्प्रतिकृतिबहुत्वे काश्यपशब्दानामेकशेषे कृते अञन्तं बहुषु वर्तत इति लुक्प्रसङ्गः॥

(समाधानभाष्यम्)

नैष दोषः। लौकिकस्य तत्र गोत्रस्य ग्रहणम्। न चैतल्लौकिकं गोत्रम्॥

(प्रदीपः) **लौकिकस्येति।** अपत्यस्येत्यर्थः॥ **न चैतदिति।** प्रतिकृतिवृत्तित्वान्नैतदञन्तमपत्यवाचि॥

(उद्योतः) **अपत्यवाचीति।** यद्यपि प्रतिकृतिवृत्त्येतद्गोत्रमेव नेति लौकिकस्येति विशेषणं व्यर्थं तथापि सिद्धान्तस्वरूपप्रदर्शनमेतत्॥ यद्वा तत्सदृशत्वात्तत्रापि गोत्रत्वाभिमानः। प्रवराध्यायप्रसिद्धं हि तत्र गोत्रशब्देन गृहीतमित्युत्तरम्॥

(पक्षान्तराभ्युपगमभाष्यम्)

अथ वा पुनरस्तु एका प्रकृतिर्बह्वश्च यञः॥

(प्रदीपः) **एका प्रकृतिरिति।** प्रकृत्यर्थस्यैकत्वात् तेन च बहूनामप्यपत्यानां सम्बन्धसम्भवात्॥

(उद्योतः) **संबन्धसंभवादिति।** प्रधानानुरोधेन गुणावृत्तिन्यायस्तु यत्र गुणावृत्तिं विना प्रधानोत्पत्तेर्न निर्वाहस्तव्यक्तव्यानीयरादौ तद्विषय इति भावः। इह तु यञाकृतेरेकत्वाद्बहूनामपि परत्वसंभवाद्गुणावृत्तिर्नापेक्ष्येति तात्पर्यम्॥

(आक्षेपसारणभाष्यम्)

ननु चोक्तमसारूप्यादेकशेषो न प्राप्नोतीति॥

(७४२ न्यासान्तरसमाधानवार्तिकम्॥ २१॥)

॥ * ॥ सिद्धं तु समानार्थानामेकशेषवचनात्॥ * ॥

(भाष्यम्) **सिद्धमेतत्। कथम्?। समानार्थानामेकशेषो भवतीति वक्तव्यम्॥**

(प्रदीपः) **सिद्धं त्विति।** सत्यपि प्रकृतिसन्निपातकृते एकस्य वैरूप्ये सर्वेषां प्रकृत्यर्थविशिष्टापत्याभिधायित्वात् समानार्थत्वमस्ति॥

(उद्योतः) **समानार्थत्वमिति।** नन्वेवं कदाचिद्यञ्शब्दमात्रस्य शेषप्रसङ्गस्तथा सति प्रकृत्यर्थविशिष्टप्रत्ययार्थानवगतिप्रसङ्गात्। नावावनड्वाहावित्यादावप्यत्र पक्षेऽनेनैवैकशेपसिद्धिः॥

(आक्षेपभाष्यम्)

यदि समानार्थानामेकशेष उच्यते, कथमक्षाः पादा माषा इति?॥

(उद्योतः) अपरः सरूपाणामित्यस्य स्थाने समानार्थानामिति मत्वाऽव्याप्तिमाह भाष्ये—यदीति ॥

(७४३ समाधानवार्तिकम् ॥ २२ ॥)

॥ * ॥ नानार्थानामपि सरूपाणाम् ॥ * ॥

(भाष्यम्) नानार्थानामपि सरूपाणामेकशेषो वक्तव्यः ॥

(उद्योतः) नानार्थानामपीति ॥ सूत्रमपि क्रियत इति भावः ॥

(७४४ न्यासान्तरवार्तिकफलितवार्तिकम् ॥ २३ ॥)

॥ * ॥ एकार्थानामपि विरूपाणाम् ॥ * ॥

(भाष्यम्) एकार्थानामपि विरूपाणामेकशेषो वक्तव्यः । वक्रदण्डश्च कुटिलदण्डश्च वक्रदण्डौ कुटिलदण्डाविति वा ॥

(प्रदीपः) वक्रदण्डश्च कुटिलदण्डश्चेति । द्वन्द्वनिवृत्त्यर्थमेतद्वक्तव्यं तेनैवान्यो बहुव्रीहिरित्यपिपक्षे आश्रीयमाणे इष्टं सिध्यति । यदा त्वनन्तं यद्बहुव्रीहिरित्याश्रीयते तदाऽव्यविकन्यायाश्रयणात् वक्रदण्डश्च कुटिलदण्डश्चेति वाक्यमेव भवति, न तु द्वन्द्व इति न वक्तव्यो विरूपाणामेकार्थानामेकशेषः ॥

(उद्योतः) तेनैवान्यो बहुव्रीहिरिति । तेनैव विरूपाणामपीतिवचनेन । वस्तुतोऽनेन गर्गयशब्दस्य शेष इति तस्यैव लुप्यमानार्थाभिधायित्वमित्यत्रापि पक्षेऽनन्तं यद्बहुव्रीहिरित्यर्थेनैव लुगिति केचित् ॥ अव्यविकेति । मन्दबुद्ध्यनुग्रहाय तु कार्यमेव वार्तिकं, सूत्रजालवत् ॥

(७४५ विभिन्नस्वराणामेकशेषनियामकवार्तिकम् ॥२४॥)

॥ * ॥ स्वरभिन्नानां यस्योत्तरः स्वरविधिः ॥ * ॥

(भाष्यम्) स्वरभिन्नानां यस्योत्तरः* स्वरविधिस्तस्यैकशेषो वक्तव्यः । अक्षश्च अक्षश्च अक्षौ, मीमांसकश्च मीमांसकश्च मीमांसकौ ॥

(प्रदीपः) स्वरभिन्नानामिति । स्वरेण भिन्नानामित्यर्थः ॥ अक्षश्चेति । एकोक्षशब्दोऽशेर्देवन इति सप्रत्ययान्तत्वादन्तोदात्तः, द्वितीयस्तु घञन्तत्वादाद्युदात्तः, तस्यैव शेषो भवति ॥ एको मीमांसकशब्दो ण्वुलन्तत्वान्मध्योदात्तः, परस्तु मीमांसामधीते इति क्रमादिभ्यो वुन्नित्याद्युदात्तस्तस्य शेषः ॥

(उद्योतः) ननु बहुव्रीहौ निष्ठान्तत्वाद्भिन्नस्य पूर्वनिपातः स्यादत आह—स्वरेणेति ॥ साधनं कृतेति समासः ॥ घञन्तत्वादिति । अक्षू व्याप्ताविति भ्वादिप्रकृतिकेत्यादिः ॥

(संख्याशब्दानामेकशेषाभावाधिकरणम्)

(आक्षेपभाष्यम्)

इह कस्मान्न भवति—एकश्च एकश्च द्वौ च द्वौ चेति ? ।

(प्रदीपः) एकश्चेति । द्वन्द्वोऽप्यत्रानभिधानान्न भवति ॥

(उद्योतः) अनभिधानस्यावश्याश्रयणीयतां दर्शयति—द्वन्द्वोपीति ॥ संख्याशब्देष्वेकादिष्वेकशेषमापादयतोऽयं भावः—द्विचतुःशब्दादिभ्योऽनेकार्थाभिधानं घटादिशब्देभ्य इव न स्यादित्यवश्यमेकशेषेणानेकार्थत्वं वक्तव्यमित्येकादिशब्दानामपि तत्प्रसङ्ग इति ॥

(७४६ समाधानवार्तिकम् ॥ २५ ॥)

॥ * ॥ संख्याया अर्थासंप्रत्ययादन्यपदार्थत्वाच्चानेकशेषः ॥ * ॥

(भाष्यम्) संख्याया अर्थासंप्रत्ययादेकशेषो न भविष्यति । नह्येकावित्यनेनार्थो गम्यते ॥ अन्यपदार्थत्वाच्च संख्याया एकशेषो न भविष्यति । एकश्च एकश्चेत्यस्य 'द्वौ' इत्यर्थः । द्वौ च द्वौ चेत्यस्य 'चत्वारः' इत्यर्थः ॥

(प्रदीपः) अर्थासंप्रत्ययादिति । यत्रैकः शब्दोनेकमर्थमभिधातुं शक्नोति तत्रैकशेषो नान्यत्र । प्रयुक्तानामन्वाख्यानाद् । एकाविति चोक्तेऽसहायादिरर्थो गम्यते न तु द्वावित्यर्थः ॥ अन्यपदार्थत्वाच्चेति । असंदिग्धेन पदान्तरेणायमर्थः प्रत्याय्यत इत्यर्थः ॥

(उद्योतः) भाष्ये—ऽर्थो गम्यतइति द्वित्वरूपार्थ इत्यर्थः ॥ द्वावित्यर्थ इति । तस्य च द्वौ शब्दो वाचक इति भावः ॥

(समाधानबाधकभाष्यम्)

नैतौ स्तः परिहारौ । यत्तावदुच्यते—'संख्याया अर्थासंप्रत्ययाद्' इति । अर्थासंप्रत्ययेपि हि सत्येकशेषो भवति । तद्यथा गार्ग्यश्च गार्ग्यायणश्च गार्ग्यौ । न चोच्यते वृद्धयुवानाविति । भवति चैकशेषः ॥ यदप्युच्यते—'अन्यपदार्थत्वाच्च' इति । अन्यपदार्थेप्येकशेषो भवति । तद्यथा विंशतिश्च विंशतिश्च विंशती इति तयोश्चत्वारिंशदित्यर्थः ॥

(प्रदीपः) गार्ग्याविति । गार्ग्यश्च गार्ग्यश्चेत्यस्याप्यर्थस्य संभवात् संदेहादर्थासंप्रत्ययः । उत्तरकालं तु प्रकरणादिवशात् संदेहनिवृत्तिः ॥ ननु वृद्धो यूनेति वचनात् संदेहेप्येकशेषः स्यात् अस्य तु निःसंदेहविषयसंभवात्कथं संदिग्धविषये प्रवृत्तिः ॥ नैतदस्ति । अक्षादिष्वपि संदेहविषयेष्वस्य प्रवृत्तिदर्शनात् ॥

(उद्योतः) संदेहादिति । निश्चयात्मकप्रतीत्यभावोऽसंप्रत्यय इत्यर्थः ॥ न चोच्यते वृद्धयुवानावित्यनेन संदेहबीजं दर्शितम् ॥

(समाधानवार्तिकाशयभाष्यम्)

एवं तर्हि नेमौ पृथक्परिहारौ । एकपरिहारोयम् 'संख्याया अर्थासंप्रत्ययादन्यपदार्थत्वाच्च'

इति ॥ यत्र ह्यर्थासंप्रत्यय एव वा, अन्यपदार्थतैव वा, भवति तत्रैकशेषः गार्ग्यौ विंशती इति यथा ॥

(प्रदीपः) एवं तर्हीति । अर्थासम्प्रत्यये सत्यन्यपदार्थत्वादित्ययं हेत्वर्थः ॥

(उद्द्योतः) एवं तर्हि नेमावित्यादिभाष्यस्य वाचकशब्दान्तरसत्ताविशिष्टार्थासंप्रत्ययेनैकार्थादशतामेकशेषाभाव इत्यत्र तात्पर्यम् । विंशत्यादीनां तु भवत्येवेति दिक् ॥

(पक्षान्तरभाष्यम्)

अथ वा नेमे एकशेषशब्दाः ॥

(उद्द्योतः) इदानीं तद्धृदयस्थमभिप्रेतं द्विशब्दादिरूपदृष्टान्तं खण्डयति—**अथवा नेमइति** । द्वावित्यादय इत्यर्थः ॥ तेषामेकशेषशब्दत्वे हि तद्दृष्टान्तेनात्रैकशेषापादनम्, न त्वेते तथेति भावः ॥

(एकशेषशब्दत्वाभावेदूषणभाष्यम्)

यदि तर्हि नेमे एकशेषशब्दाः समुदायशब्दास्तर्हि भवन्ति ॥ तत्र को दोषः ? । एकवचनं प्राप्नोति ॥ एकार्था हि समुदाया भवन्ति यूथं शतं वनमिति ॥

(प्रदीपः) यदितर्हीति । प्रत्यर्थं शब्दनिवेशादेकशेषे सति एकस्यानेकार्थत्वं सम्भवति । यदा तु समुदायवाचित्वं द्व्यादीनामभ्युपगम्यते तदा वनादिवदेकवचनप्रसङ्गः ॥ यत्तु वनानीति बहुवचनं तत्समुदायप्रचयविवक्षायां न त्ववयवभेदविवक्षायाम् ॥ **समुदाया इति** समुदायवाचिन इत्यर्थः ॥

(उद्द्योतः) यदा त्विति । एकशेषं विनैवेत्यर्थः ॥ ननु समुदायो नामार्थः, न च तस्यार्थोस्तीत्यत आह—**समुदायवाचिन इति** ॥

(एकशेषशब्दत्वाङ्गीकारभाष्यम्)

सन्तु तर्ह्येकशेषशब्दाः ॥ किंकृतं सारूप्यम् ? । अन्योन्यकृतं सारूप्यम् ॥

(प्रदीपः) **किं कृतमिति** । एकश्चैकश्चेति विग्रहे कथं द्विशब्दः प्रवर्तत इति प्रश्नः ॥ **अन्योन्यकृतमिति** । परस्परापेक्षया द्वित्वोत्पत्तौ सत्यां प्रक्रियावाक्यमिदं भवति द्वौ च द्वौ चेति । तत्रैको द्विशब्दः शिष्यते ॥

(उद्द्योतः) **प्रश्न इति** । एकश्चैकश्चेति विग्रहे शिष्यमाणाद्विशब्देन किंसादृश्यमित्यर्थः ॥ **परस्परेति** । एकशब्दयोः सहविवक्षायां शिष्यमाणैकशब्दस्य तदर्थाभिधानासामर्थ्यात् परस्परापेक्षयैकैकत्रार्थे द्वित्वोत्पत्तौ तदभिधानसमर्थशब्दप्रवृत्तिः, तदलौकिकं च द्वौ च द्वौ चेत्यादीति भावः ॥ अन्योन्यापेक्षाकृतद्वित्वेन प्रत्येकं द्विशब्दप्रवृत्त्या सारूप्यमिति भाष्याक्षरार्थः ॥ अत एवाग्रेऽन्योन्यकृतभावविषय एव प्रश्नः ॥

(दृष्टान्तपक्षभाष्यम्)

सन्ति पुनः केचिद् अन्येऽपि शब्दाः येषामन्योन्यकृतो भावः ? ।

(उद्द्योतः) अन्योन्यकृत इत्यस्य परस्परकृत इत्यर्थः । भावः प्रवृत्तिनिमित्तम् ॥

(दृष्टान्तप्रदर्शकभाष्यम्)

सन्तीत्याह ॥ माता पिता भ्रातेति ॥

(प्रदीपः) **मातेति** । यथा सुतजन्मनः प्रागलब्धमातृव्यपदेशं स्त्री पश्चाल्लभते, एवं संख्येयान्तरापेक्षायां सत्यां पूर्वमप्रवृत्तो द्विशब्दः पश्चात्प्रवर्तत इत्यर्थः ॥

(उद्द्योतः) मातृपुत्रादिशब्दाश्च परस्परकृतमातृत्वपुत्रत्वादिनिबन्धनास्तदाह यथेति ॥

(दृष्टान्तवैषम्यभाष्यम्)

विषम उपन्यासः । सकृदेते शब्दाः प्रवृत्ता अपायेष्वपि वर्तन्ते । इह पुनरेकेनाप्यपाये न भवति चत्वार इति ॥

(प्रदीपः) **अपायेष्वपीति** । पुत्रविनाशेपि पितृव्यपदेशो न निवर्तते, पितृविनाशे पुत्रव्यपदेशः । चतुर्णां त्वेकापाये नास्ति चतुःशब्दस्य प्रवृत्तिः ॥

(उद्द्योतः) **पुत्रविनाशेपीति** । ननु पुत्रस्य बुद्धिस्थत्वेन तन्नाशेपि पितृव्यवहारोस्त्येव, भाविपुत्रस्य पितेति व्यवहारवत् प्रकृतेप्येकस्य बुद्धिस्थत्वे तदपायेपि चतुरादिव्यवहार इति किं वैषम्यं पुत्रस्याबुद्धिस्थत्वे तु तत्सत्त्वेपि न पितृव्यवहार इति चेन्न । नष्टस्य पितेति व्यवहारवन्नष्टबुद्धिस्थं पदार्थमादायैकस्य विद्यमानत्वे द्वौ स्त इत्यादिव्यवहाराभाव इति वैषम्यमित्याशयात् ॥ **नास्ति चतुःशब्दस्येति** । एवं च दृष्टान्तदार्ष्टान्तिकयोर्वैषम्यमिति भावः ॥

(दृष्टान्तवैषम्यपरिहारभाष्यम्)

अन्यदिदानीमेतदुच्यते—'सकृदेते शब्दाः प्रवृत्ता अपायेष्वपि वर्तन्ते' इति ॥ यत्तु भवानस्मांश्चोदयति—'सन्ति पुनः केचिदन्येऽपि शब्दा येषामन्योन्यकृतो भावः' इति । तत्रैतेस्माभिरुपन्यस्ताः । तत्रैतद्भवानाह—'सकृदेते शब्दाः प्रवृत्ता अपायेष्वपि वर्तन्ते' इति ॥ एतच्च वार्तम् ।

एकैको नोद्यन्तुं भारं शक्नोति यत्कथं तत्र ।
एकैकः कर्ता स्यात्सर्वे वा स्युः कथं युक्तम् ॥ १ ॥
कारणमुद्यमनं चेच्चोद्यच्छति चान्तरेण तत्तुल्यम् ।
तस्मात्पृथक् पृथक् ते कर्तारः सव्यपेक्षास्तु ॥ २ ॥

(प्रदीपः) **अन्यदिदानीमिति** । अवश्यं साधर्म्ये सति वैधर्म्येण भाव्यम् । अन्यथा तत्त्वमेव स्याद् न तु साधर्म्यम् । तत्रै वैधर्म्योद्भावने न कश्चिदपि हेतुः स्यादि-

त्यर्थः ॥ मात्रादयश्च शब्दाः सम्बन्ध्यन्तरापेक्षयैकस्मिन्नाश्रये वर्तन्त इति सम्बन्ध्यन्तरविनाशेपि आश्रयसद्भावाद्युक्तं यत्प्रवर्तन्ते । द्व्यादयस्तु समुदायनिवेशिन एकापाये तत्समुदायाभावात्कथं प्रवर्तेरन् ॥ **एतच्च वार्तमिति** । एतद्युक्तम्—यदाश्रयसन्निधानादेकापायेपि मात्रादयस्तदपेक्षाः प्रवर्तन्त इत्यर्थः ॥ इदानीमेतद्वैधर्म्यरहितं द्वितीयं दृष्टान्तं वक्ति **एकैक इति** ॥ यथोद्यन्तॄणां परस्परसन्निधिकृतं कर्तृत्वमेकैकापाये च निवर्तते तथा द्व्यादिव्यपदेशोपीत्यर्थः ॥ **कथं तर्हीति** । न्याय्यमित्यध्याहारः ॥ **एकैक इति** । परस्परनिरपेक्षमित्यर्थः ॥ **कारणमुद्यमनं चेदिति** । कर्तृत्वप्रतीताविल्यर्थः ॥ कार्यकल्पितत्वाच्छक्तीनामिवमुक्तम् ॥ **तत्तुल्यमिति** । तेनोद्यन्त्रा तुल्यं द्वितीयमुद्यन्तारमन्तरेणेत्यर्थः ॥ अथवा **तत्तुल्यमिति** । द्व्यादिशब्देष्वप्येतत्तुल्यमित्यर्थः ॥

(उद्द्योतः) नन्वेवं परिहारे दृष्टान्तदार्ष्टान्तिकभावः क्वापि न स्यादित्याह—**अन्यदिदानीमिति** । तथाचष्टे—**अवश्यमिति** । एवं चेदृशे विषये वैधर्म्योद्भावनमकिंचित्करमिति भावः ॥ साधर्म्ये सत्यप्युक्तवैधर्म्ये बीजमाह—**मात्रादय इति** । **आश्रयसद्भावादिति** । सद्भावोत्र बुद्धिकृतस्तेन मृता मातेत्याद्युपपत्तिः ॥ **समुदायेति** । इतरसाहित्यविशिष्टद्रव्यनिवेशिन इत्यर्थः ॥ वार्तमित्यस्यासारमित्यर्थ इतन्ये ॥ भाष्ये **यदित्यस्य** यत्रेत्यर्थः ॥ **सर्वे** परस्परसापेक्षा इत्यर्थः ॥ ननूद्यमनस्यैव कर्तृत्वप्रतीतौ कारणत्वात्तस्य च प्रत्येकवृत्तित्वादेकैक इत्येव युक्तं तत्राह—**कारणमुद्यमनं चेदिति** । स्वतुल्यद्वितीयसहायं विनाप्युद्यमनं स्यान्न च तथा दृश्यते, तस्मात्परस्परसापेक्षं पृथक् पृथक्कर्तृत्वमित्यर्थः ॥ एवं च तत्र यथान्योन्यकृतेनोद्यमनकर्तृत्वरूपार्थेन प्रत्येकस्मिंस्तेन सह उद्यच्छतीतिशब्दस्तथान्योन्यसव्यपेक्षद्वित्वेनैकैकस्मिन्नपि द्विशब्दप्रवृत्तिरिति **सिद्धमेकशेषशास्त्रम्** ॥ द्वौ च द्वौ चेतिविग्रहः, द्वित्ववैशिष्ट्येन बोधाच्च प्रत्येकं द्विवचनं, प्रयोगे त्वेकशेषेणैव प्रयोगान्न कदाप्येकबोधो द्वावित्यतः । एवं चैको न द्वावित्याद्युपपन्नम् ॥ द्वौ नैकस्त्रयो न द्वावित्येवंविधव्यवहारादुत्तरसंख्यायाः पूर्वसंख्याबाधकत्वमिति तत्त्वम् ॥ **अथ वेति** । अत्र पक्षे **तत्तुल्यमिति** सव्यपेक्षास्त्वित्युत्तरं योज्यम् । **नोद्यच्छति** चान्तरेणेत्यत्र स्वसमकक्षं सहायमिति शेषो बोध्यः । वस्तुतो द्व्यादीनामेकशेषशब्दत्वाभावेपि नियमत उद्भूतावयवभेदसमुदायविवक्षणेन न कदाचिदपि द्व्यादिभ्य एकवचनम् ॥ **अथ वा नेम** इति भाष्यस्यायमेवार्थ एकशेषेणाप्ययमेवार्थः सूचित इति बोध्यम् ॥

(प्रथममध्यमोत्तमानामेकशेषविधानाधिकरणम्)

(७४७ आक्षेपवार्तिकम् ॥ २६ ॥)

॥ * ॥ प्रथममध्यमोत्तमानामेकशेषोऽसरूपत्वात् ॥ * ॥

(भाष्यम्) प्रथममध्यमोत्तमानामेकशेषो वक्तव्यः । पचति च पचसि च पचथः । पचसि च पचामि च पचावः । पचति च पचसि च पचामि च पचामः ॥ किं पुनः कारणं न सिध्यति ? । असरूपत्वात् ॥

(प्रदीपः) **प्रथमेति** । एकस्मिन् पुरुषे क्रियाया एकत्वान्नास्त्येकशेषः, पुरुषभेदेन तु प्रत्यक्षपरोक्षादिभेदे विरोधात् क्रियाया अनेकत्वादेकशेषो वक्तव्यः । कृते चैकशेषे प्रकरणादिवशादर्थविशेषावसायः ॥ यदा तु युष्मदस्मदी एवानेकार्थाभिधानसमर्थे इति पक्षः । अत्रापि च निवृत्तभेदाया एव क्रियाया आख्यातेनाभिधानं तदैकशेषो न वक्तव्यः ॥

(उद्द्योतः) भाष्ये **प्रथमेति** । प्रथमेन मध्यमः, प्रथमादिनोत्तम इति वक्तव्यमित्यर्थः ॥ **पुरुषे** । प्रथमाद्यन्यतमे ॥ **एकत्वादिति** । भेदावगमे हेतोरभावादित्यर्थः ॥ **प्रत्यक्त्वम्** । अहंकारानास्पदचैतन्यम् ॥ **पराक्त्वम्** । तदास्पदचेतनत्वम् ॥ **आदिना** प्रत्यक्षत्वपरोक्षत्वे ॥ **प्रकरणादीति** । गार्ग्यावित्यत्र वृद्धयूनोरिवेति भावः ॥ **यदा त्विति** । त्यदादीनीत्येकशेषारम्भादिति भावः ॥ **आख्यातेनाभिधानमिति** । प्रथमत इति शेषः । पश्चाद्द्वित्वादिप्रत्ययः समभिव्याहारादिति भावः ॥ एवं चेदं वचनमवैयाकरणतार्किकस्येति तात्पर्यम् । स्वरूपव्याक्रिययैव चास्य प्रत्याख्यातप्रायत्वाद्द्विवचनाद्यसिद्धेश्च नास्य विशिष्य प्रत्याख्यानं भाष्ये इति बोध्यम् ॥ **असरूपत्वादिति** । असमानशब्दत्वादसमानार्थत्वाच्चेत्यर्थः । द्विवचनेत्यादिग्रन्थस्तु वृक्षावित्याद्यभिप्रायकः सूत्रं प्रत्याख्यातुम् ॥

(सूत्रप्रत्याख्यानाधिकरणम्)

(७४८ आक्षेपवार्तिकम् ॥ २७ ॥)

॥ * ॥ द्विवचनबहुवचनाप्रसिद्धिरेकार्थत्वात् ॥ * ॥

(भाष्यम्) द्विवचनबहुवचनयोश्चाप्रसिद्धिः ॥ किं कारणम् ? । 'एकार्थत्वात्' एकोयमवशिष्यते तेनानेन तदर्थेन भवितव्यम् ॥ किमर्थेन? । यदर्थ एकः ॥ किमर्थश्चैकः ? । एकार्थः ॥

(प्रदीपः) **द्विवचनेति** । प्रत्यर्थं शब्दनिवेशे एकैकः शब्दः एकैकार्थाभिधायीति सहविवक्षायां निवृत्तेषु शब्दान्तरेषु शिष्यमाणेन शब्देन स्वस्मिन्नेवैकत्रार्थे अवस्थेयमिति भावः। सर्वेषु पक्षेष्वयं दोषः प्रातिपदिकैकशेषे द्विवचनबहुवचनानुत्पत्तिप्रसङ्गः विभक्त्यन्तानां विभक्तौ वा परत एकशेषेऽर्थाभावाद् द्विवचनबहुवचनयोर्निवृत्तिप्रसङ्गः । अथ स्वभावतः शिष्यमाणोऽनेकार्थः किमेकशेषेण ॥

(उद्द्योतः) **निवृत्तिप्रसङ्ग इति** । जातनिवृत्तौ मानाभावात्सत्त्वेपि तदर्थाभावेन तद्बाधप्रसङ्ग इति वक्तुं युक्तम् ॥

(७४९ समाधानवार्तिकम् ॥ २८ ॥)

॥ * ॥ नैकार्थ्यम् ॥ * ॥

(भाष्यम्) नायमेकार्थः ॥ किं तर्हि ? । द्व्यर्थो बह्वर्थश्च ॥

(७५० आक्षेपवार्तिकम् ॥ २९ ॥)

॥ * ॥ नैकार्थ्यमिति चेदारम्भानर्थक्यम् ॥ * ॥

(भाष्यम्) नैकार्थ्यमिति चेदेकशेषारम्भोनर्थकः स्यात् ॥ इह हि शब्दस्य स्वाभाविकी वाऽनेकार्थता स्यात् । वाचनिकी वा ॥

(प्रदीपः) **वाचनिकी वेति** । यद्यपि सर्वमेव स्वाभाविकं तथापि यत्र प्रयोगविप्रयोगौ दृश्येते तत्र विप्रयोगनिवारणाय यदुच्यते तद्वाचनिकमभिधीयते ॥

(उद्योतः) **यद्यपीति** । शब्दार्थसंबन्धस्य नित्यत्वादिति भावः ॥ **विप्रयोगः** द्वन्द्वरूपः ॥

(स्वाभाविकत्वे प्रत्याख्यानभाष्यम्)

तद्यदि तावत्स्वाभाविकी—

(७५१ प्रत्याख्यानवार्तिकम् ॥ ३० ॥)

॥ * ॥ अशिष्य एकशेष एकेनोक्तत्वात् ॥ * ॥

(भाष्यम्) अशिष्य एकशेषः ॥ किं कारणम् ? । एकेनोक्तत्वात्तस्यार्थस्य द्वितीयस्य प्रयोगेण न भवितव्यम् उक्तार्थानामप्रयोग इति ॥

(वाचनिकत्वेवचनावश्यकत्वभाष्यम्)

अथ वाचनिकी, तद्वक्तव्यम्—'एकोयमवशिष्यते, स च द्व्यर्थो भवति बह्वर्थश्च' इति ॥

(प्रदीपः) **स च द्व्यर्थइति** 'सरूपाणामेकशेषोनेकार्थश्चेकविभक्तौ' इति वक्तव्यमित्यर्थः ॥

(वचनानावश्यकताभाष्यम्)

न वक्तव्यम् सिद्धमेकशेष इत्येव ॥

(प्रदीपः) **सिद्धमिति** । एकशेषारम्भसामर्थ्यादयमर्थो गम्यते शिष्यमाणः शब्दोनेकार्थाभिधायीति । एकेन ह्यनेकार्थाभिधानायैकशेषः क्रियते । एकार्थाभिधाने त्वनेकशब्दाप्रसङ्गादनर्थक एकशेषः स्यादित्यर्थः ॥

(तृतीयस्याक्षेपभाष्यम्)

कथं पुनरेकोयमवशिष्यत इत्यनेन द्व्यर्थता बह्वर्थता च शक्या लब्धुम् ? ॥

(प्रदीपः) इतर एतत्सामर्थ्यमजानन्नाह—**कथमिति** ॥

(एकशेषवादिनः समाधानभाष्यम्)

तच्चैकशेषकृतम् । नह्यन्तरेण तद्वाचिनः शब्दस्य प्रयोगं तस्यार्थस्य गतिर्भवति । पश्यामश्च पुनरन्तरेणापि तद्वाचिनः शब्दस्य प्रयोगं तस्यार्थस्य गतिर्भवति अग्निचित्सोमसुदिति यथा । ते मन्यामहे—लोपकृतमेतद्—येनात्र अन्तरेणापि तद्वाचिनः शब्दस्य प्रयोगं तस्यार्थस्य गतिर्भवतीति । एवमिहाप्येकशेषकृतमेतद्–येनात्रैकोयमवशिष्यत इत्यनेन द्व्यर्थता बह्वर्थता च भवति ॥

(प्रदीपः) **तच्चैकशेषकृतमिति** । एकशेषविधानेनैतत्प्रतिपादितमित्यर्थः ॥ **लोपकृतमिति** । लोपद्वारेणैतत्संगृहीतमित्यर्थः ॥ **अनेनेति** । एकशेषविधानेन ॥

(उद्योतः) **एतत्प्रतिपादितमिति** । भाष्ये—**कृतमिति** करोतिरेकशेषविधानसामर्थ्यलब्धप्रतिपादने वर्तते, तेन शब्दार्थसंबन्धनित्यत्वेपि न क्षतिरिति भावः ॥ लोपस्याभावात्मकत्वात्तत्कृतत्वमर्थावगतेरनुपपन्नमत आह—**लोपद्वारेणेति** । एवं च शिष्यमाणस्य लुप्यमानार्थबोधकत्वमनुभवसिद्धमिति भावः ॥ भाष्ये—**बह्वर्थता वा भवतीति** । वा चार्थे ॥ क्वचित् चेत्येव पाठः । विद्यमानैव बोध्यते इत्यर्थः ॥

(एकशेषप्रत्याख्यातुराक्षेपभाष्यम्)

उच्येत तर्हि न तु गम्येत । यो हि गामश्व इति ब्रूयादश्वं वा गौरिति, न जातुचित्संप्रत्ययः स्यात् । तेनानेकार्थाभिधाने यत्नं कुर्वताऽवश्यं लोकः पृष्ठतोनुगन्तव्यः 'केष्वर्थेषु लौकिकाः कान् शब्दान्प्रयुञ्जते' इति । लोके चैकैकस्मिन् वृक्ष इति प्रयुञ्जते, द्वयोर्वृक्षौ, बहुषु वृक्षा इति ॥ यदि तर्हि लोकोवश्यं शब्देषु प्रमाणं किमर्थमेकशेष आरभ्यते ? ॥

(प्रदीपः) **उच्येतेति** । वचनादनेकार्थकार्याणि प्रवर्तन्तां यथा जात्याख्यायामेकस्मिन्निति, न त्वेकार्थः शब्द एकशेषविधानेनानेकार्थः संपद्यत इत्यर्थः ॥ **गामश्व इति** । अश्वधर्मसमारोपः केवलं प्रतीयते, न तु तात्त्विकमश्वत्वमित्यर्थः ॥ **यदि तर्हीति** । यदि च लोकः प्रमाणमित्यर्थः ॥ **उच्यते तर्हीत्यतः** प्रभृति सर्वो ग्रन्थ एकशेषप्रत्याख्यानवादिनः ।

(उद्योतः) एतदजानान इतरः शङ्कते—**उच्येत तर्हीति** । तद् व्याचष्टे—**वचनादिति** । शास्त्रस्य शास्त्रीयकार्यार्थत्वादिति भावः । **संप्रत्ययः स्यादिति** । भाष्ये अश्वत्वादिप्रमा स्यादित्यर्थः ॥ तर्हि शब्दस्य चार्थतया व्याख्याने मानं दर्शयति **सर्वो ग्रन्थ** इति ॥

(एकशेषवादिनः प्रत्याक्षेपभाष्यम्)

अथ किमर्थं लोप आरभ्यते ? ॥

(उद्योतः) भाष्ये **अथ किमर्थं लोप इति** । अग्निचिदित्यतो लोकत एव कर्त्रर्थप्रतीतिसिद्धेरिति भावः ॥

(एकशेषप्रत्याख्यातुःसमाधानभाष्यम्)

प्रत्ययलक्षणमाचार्यः प्रार्थयमानो लोपमारभते एकशेषारम्भे पुनरस्य न किंचित्प्रयोजनमस्ति ॥

(उद्योतः) प्रत्ययलक्षणमिति। अनेन लोपेनानुत्पत्तेरेवा-न्वाख्यानमित्युक्तम् ॥

(आक्षेपसारणभाष्यम्)

ननु चोक्तम् * प्रत्यर्थं शब्दनिवेशान्नैकेनानेकस्याभिधानम् * इति। यदि चैकेनानेकस्याभिधानं स्यात् न प्रत्यर्थं शब्दनिवेशः कृतः स्यात् ॥

(उद्योतः) न प्रत्यर्थमिति। ततश्च वृक्षश्च वृक्षश्चेति वाक्यं न स्यादिति भावः ॥

(७५२ आक्षेपसमाधानवार्तिकम् ॥ ३१ ॥)

॥ * ॥ प्रत्यर्थं शब्दनिवेशान्नैकेनानेकस्याभिधानादप्रत्यर्थमिति चेत्तदपि प्रत्यर्थमेव ॥ * ॥

(भाष्यम्) प्रत्यर्थं शब्दनिवेशान्नैकेनानेकस्याभिधानाद् अप्रत्यर्थमिति चेदेवमुच्यते यदप्येकेनानेकस्याभिधानं भवति तदपि प्रत्यर्थमेव। यदपि द्व्यर्थावर्थौ प्रति तदपि प्रत्यर्थमेव। यदपि ह्यर्थानर्थान्प्रति तदपि प्रत्यर्थमेव ॥

(प्रदीपः) तदपि प्रत्यर्थमेवेति। अर्थो ह्यभिधेयमुच्यते यश्च द्व्यर्थः शब्दो नासौ द्व्यर्थतां जहाति बह्वर्थश्च बह्वर्थतां रोदसी दारा इति यथेत्यर्थः ॥

(उद्योतः) इतराभिमतमनूद्य दूषयति—प्रत्यर्थमित्यादि। प्रत्यर्थं शब्दनिवेशादेकेनानेकाभिधानाभावादेकशेष आरब्धव्योऽन्यथाऽप्रत्यर्थं स्यात्। एकेनानेकस्याभिधाने प्रत्यर्थशब्दप्रयोगो न स्यादिति चेदित्यर्थः। यदप्येकेनेति। अपिनैतत्सूचयति नैकेनैकस्याभिधानं वयं निराकुर्मः, किं तु सहविवक्षायामेकेनानेकाभिधानमपि स्वीकुर्मस्तेन वाक्यसिद्धिः। एकशेषारम्भश्च न कार्यः, द्वन्द्वस्य तु प्रयोगादर्शनान्नतन्निवृत्त्यर्थोपि स इति ॥ तदपीति। स्वीयस्वीयार्थात्याग एव प्रत्यर्थत्वमिति भावः ॥

(७५३ सूत्रारम्भवादिन आक्षेपवार्तिकम् ॥ ३२ ॥)

॥ * ॥ यावतामभिधानं तावतां प्रयोगो न्याय्यः ॥ * ॥

(भाष्यम्) यावतामर्थानामभिधानं भवति तावतां शब्दानां प्रयोग इत्येव पक्षो न्याय्यः।

(प्रदीपः) यावतामिति। वृक्षश्च वृक्षश्चेति दर्शनादनारब्ध एकशेषे अनेकार्थतैकस्य न स्यात् ॥

(उद्योतः) आरम्भवाद्याह यावतामिति। एष एव न्याय्य इत्यर्थः ॥ न्याय्यत्वं कुत इत्यत आह—वृक्षश्चेति ॥ एकस्य न स्यादिति। प्रयोगे इति शेषः ॥

(७५४ प्रत्याख्यानवादिनः समाधानवार्तिकम् ॥ ३३ ॥)

॥ * ॥ यावतामभिधानं तावतां प्रयोगो न्याय्य इति चेदेकेनाप्यनेकस्याभिधानम् ॥ * ॥

(भाष्यम्) यावतामभिधानं तावतां प्रयोगो न्याय्य इति चेदेवमुच्यते। एषोपि पक्षो न्याय्य एव यदप्येकेनानेकस्याभिधानं भवति ॥

(प्रदीपः) एकेनापीति। सहविवक्षायामेक एव शब्द उद्भूतावयवभेदं समुदायमभिधत्त इत्यर्थः ॥

(उद्योतः) प्रत्याख्यानवादी आह—यदप्येकेनेति। वृक्षाविस्यादिदर्शनादिति भावः ॥ सहेति। समुदायार्थप्रादुर्भावादिति भावः। द्विवचनाद्युत्पत्त्यर्थमाह उद्भूतेति ॥

(आक्षेपवार्तिकशेषभाष्यम्)

यदि तर्ह्येकेनानेकस्याभिधानं भवति प्लक्षन्यग्रोधौ—

(७५५ आक्षेपवार्तिकम् ॥ ३४ ॥)

॥ * ॥ एकेनोक्तत्वादपरस्य प्रयोगोऽनुपपन्नः ॥ * ॥

(भाष्यम्) एकेनोक्तत्वात्तस्यार्थस्यापरस्य प्रयोगेण न भवितव्यम्। किं कारणम्?। उक्तार्थानामप्रयोग इति ॥

(प्रदीपः) प्लक्षन्यग्रोधाविति। अत्रापि सहविवक्षायां समुदायार्थप्रादुर्भावादेकेनैव समुदायस्य प्रतिपादनाद् द्वितीयस्य प्रयोगो न प्राप्नोतीत्यर्थः ॥

(उद्योतः) आरम्भवाद्याह—यदीति। एकेनैवेति। युगपदधिकरणवचनतारीत्यर्थः ॥

(७५६ समाधानवार्तिकम् ॥ ३५ ॥)

॥ * ॥ एकेनोक्तत्वादपरस्य प्रयोगोऽनुपपन्न इति चेदनुक्तत्वात्प्लक्षेण न्यग्रोधस्य न्यग्रोधप्रयोगः ॥ * ॥

एकेनोक्तत्वादपरस्य प्रयोगोऽनुपपन्न इति चेदनुक्तः प्लक्षेण न्यग्रोधार्थ इति कृत्वा न्यग्रोधशब्दः प्रयुज्यते ॥

(प्रदीपः) अनुक्तत्वादिति। प्लक्षावित्युक्ते प्लक्षस्य प्लक्षान्तरेण सहत्वं गम्यते न तु न्यग्रोधेनेत्यर्थः ॥

(उद्योतः) प्लक्षान्तरेणेति। सजातीयत्वाद् झटिति बुद्धिस्थेनेत्यर्थः ॥

(आक्षेपभाष्यम्)

कथमनुक्तः। यदिदानीमेवोक्तमेकेनाप्यनेकस्याभिधानं भवतीति?।

(समाधानभाष्यम्)

सरूपाणामेकेनाप्यनेकस्याभिधानं भवति न विरूपाणाम् ॥

(उद्द्योतः) भाष्ये—**एकेनापीति** । अपिनानेकेनापि ॥

(आक्षेपभाष्यम्)

किं पुनः कारणं सरूपाणामेकेनाप्यनेकस्याभिधानं भवति, न पुनर्विरूपाणाम् ॥

(७५७ समाधानवार्तिकम् ॥ ३६ ॥)

॥ * ॥ अभिधानं पुनः स्वाभाविकम् ॥ * ॥

(भाष्यम्) **स्वाभाविकमभिधानम् ॥**

(७५८ समाधानहेतुवार्तिकम् ॥ ३७ ॥)

॥ * उभयदर्शनाच्च ॥ * ॥

(भाष्यम्) **उभयं खल्वपि दृश्यते विरूपाणामप्येकेनानेकस्याभिधानं भवति । तद्यथा 'द्यावा ह क्षामा' 'द्यावा चिदस्मै पृथिवी नमेते' इति । विरूपाणां किल नामैकेनानेकस्याभिधानं स्यात् किं पुनः सरूपाणाम् ॥**

(प्रदीपः) **उभयदर्शनाच्चेति** । सरूपस्य विरूपस्य चैकस्यानेकार्थाभिधायित्वदर्शनादित्यर्थः ॥ **द्यावेति** । द्योशब्देन द्यावापृथिव्योरभिधानात् ततः परस्यौकारस्य **सुपां सुलुगित्याकारः**, **गोतो णिदित्योकारान्तग्रहणाण्णित्वाद्वृद्धिरावादेशश्च** ॥ **पृथिवी इति** । द्विवचनान्तं । **वा छन्दसीति** पूर्वसवर्णदीर्घः ॥ पृथिवीशब्देनात्र दिवस्पृथिव्योरभिधानम् ॥ **विरूपाणामिति** । प्रकरणादिवशाद्यत्रार्थविशेषावसायस्तत्र प्रवृत्तिनिमित्तभेदेपि विरूपोऽनेकार्थाभिधायी दृश्यते, तत्र सरूपः कथं न स्याद्यत्रैकं प्रवृत्तिनिमित्तमित्यर्थः ॥

(उद्द्योतः) प्रत्याख्यानबाधेव युक्त्यन्तरमाह—**उभयदर्शनाच्चेति** । उभयोरप्येकेनानेकार्थाभिधानदर्शनादित्यर्थः ॥ तद्व्याचष्टे—**सरूपस्य चेति** ॥ **द्विवचनान्तमिति** । अत एव पदकाले **पृथिवी इतीति** प्रगृह्यत्वम् ॥ ननु द्यावेत्यादाविव प्लक्षावित्यादावपि विजातीयानेकार्थाभिधानं स्यादिति चेन्न । स्वभावेन वारणात् ॥ **यत्रैकं प्रवृत्तिनिमित्तमिति** । तत्र शक्यतावच्छेदकप्रकारकबोधाङ्गीकारे तदनुगतीकृतानेकव्यक्तिबोधो न्याय्य एवैकस्माद् द्रव्यपदार्थवादेपि । शुद्धव्यक्तिबोध इति वादिनां मतेपि प्रवृत्तिनिमित्तोपलक्षितानेकव्यक्तौ शक्तिग्रहात्तात्पर्यग्राहकसत्त्वे एकस्मादप्यनेकशुद्धव्यक्तिबोध इति सर्वथा द्रव्यपक्षेपि सूत्रं प्रत्याख्यातम् ॥

(७५९ आकृतिपक्षवार्तिकम् ॥ ३८ ॥)

॥ * ॥ आकृत्यभिधानाद्वैकं विभक्तौ वाजप्यायनः ॥ * ॥

(भाष्यम्) **आकृत्यभिधानाद्वा एकं शब्दं विभक्तौ वाजप्यायन आचार्यो न्याय्यं मन्यते ॥ एका आकृतिः, सा चाभिधीयते इति ॥**

(प्रदीपः) तदेवं द्रव्याभिधानपक्षेपि प्रत्याख्यात एकशेषः । अनेकार्थप्रक्रमे अनेकार्थ एक एव वृक्षशब्दः प्रयुज्यते । न तु द्वन्द्वः अनभिधानात् ॥ इदानीमाकृतिपक्षाश्रयेण प्रत्याख्यानं करोति—**आकृत्यभिधानादिति** । जातिः शब्दार्थः तस्याः एकत्वादनेकशब्दप्रयोगप्रसङ्ग एव नास्ति किमेकशेषेणेत्यर्थः ॥

(उद्द्योतः) इदमेव तत्त्वं यदेकस्य युगपदनेकार्थबोधकत्वं तदाह—**प्रत्याख्यात इति** । इदं च प्रत्याख्यानमर्थस्यान्यप्रमाणत्वादित्यनेन सूत्रकृतापि दर्शितप्रायमेव ॥ नन्वेवमपि द्वन्द्वो दुर्वारोऽत आह—**न त्विति** । सहविवक्षायामेकजातीयार्थानेकशब्दप्रयोगादर्शनेन तदसाधुत्वप्रतिपादनार्थं सूत्रमिति भावः ॥ **एकाऽऽकृतिरिति** भाष्यस्यास्तीति शेषः ॥ **शब्दार्थः** । शब्दजप्रतीतिविशेष्यः ॥

(आक्षेपभाष्यम्)

कथं पुनर्ज्ञायते—एका आकृतिः सा चाभिधीयते इति ॥

(प्रदीपः) **कथं पुनरिति** । द्रव्यातिरेकेणाकृतेरनुपलम्भादभावं मन्यमानस्य प्रश्नः ॥

(७६० समाधानवार्तिकम् ॥ ३९ ॥)

॥ * ॥ प्रख्याविशेषात् ॥ * ॥

(भाष्यम्) **नहि गौरित्युक्ते विशेषः प्रख्यायते—शुक्ला नीला कपिला कपोतिकेति ॥**

(प्रदीपः) **प्रख्याविशेषादिति** । प्रख्या बुद्धिः तस्या अविशेषादेकरूपत्वात् तद्विषयस्याप्यैक्यं प्रतीयते । गुणप्रमाणादिभिन्नेष्वपि गोपिण्डेषु गौर्गौरित्येकाकारप्रत्ययोदयादवश्यमेकेनालम्बनेन सामान्येन भाव्यमिति जातिसद्भाव एकत्वं चावसीयते ॥ **गौरित्युक्तइति** । गौरित्येतेन शब्देनोक्ते प्रत्यायिते

सामान्यलक्षणेयं विशेषानवधारणादैक्यं सामान्यस्यावसीयत इत्यर्थः ॥

(उद्योतः) बुद्धिरिति। प्रमात्मिकेत्यर्थः। ननु व्यक्त्यैक्ये स्यादेव प्रतीत्यैकरूपतेत्यत आह—गुणेति ॥ आलम्बनेनेति। विषयेणेत्यर्थः ॥ प्रख्यायित इति। अनेकशोपीत्यादिः ॥ विशेषानवधारणादिति। आश्रयभेदेपीत्यादिः ॥

(आक्षेपभाष्यम्)

यद्यपि तावत्प्रख्याविशेषाद् ज्ञायते—एका आकृतिरिति, कुतस्त्वेतत्—साभिधीयते इति ॥

(प्रदीपः) **कुतस्त्वेतदिति।** भवतु सामान्यमेकं तस्य तु वाहदोहादिकायामर्थक्रियायामयोग्यत्वाद्, द्रव्यस्यैव योग्यत्वाद् अभिधानं न्याय्यमिति मत्वा प्रश्नः ॥

(७६१ समाधानवार्तिकम् ॥ ४० ॥)

॥ * ॥ अन्यपवर्गगतेश्च ॥ * ॥

(भाष्यम्) **अन्यपवर्गगतेश्च मन्यामहे 'आकृतिरभिधीयते' इति। नहि गौरित्युक्ते व्यपवर्गो गम्यते—शुक्ला नीला कपिला कपोतिकेति ॥**

(प्रदीपः) **अव्यपवर्गगतेश्चेति।** अव्यपवर्गोऽभेदः अविच्छेदः अविशेषस्तस्य गतिः प्रतीतिरित्यर्थः। जातौ चाभिधीयमानायां द्रव्यद्वारका वाहदोहादय उपपद्यन्ते, जातितद्वतोश्चाभेदोपचाराद् गौः शुक्ल इति सामानाधिकरण्यादिव्यवहारोप्युपपद्यते ॥ अथ प्रख्याविशेषादव्यपवर्गगतेश्चेति किमर्थमुभयोरुपादानम्। एकेनापि हेतुनैकत्वाभिधानयोः सिद्धत्वात्॥ नैष दोषः। अनभिधीयमानापि जातिः संनिधिमात्रेण प्रख्याऽविशेषे निमित्तं भवतीति प्रख्याऽविशेषेण प्रत्यभिज्ञाप्रत्ययरूपेणैकत्वमेव प्रतिपादितं नाभिधानम्। तथा वनमिति सर्वविशेषाभ्यन्तरीकरणेनाव्यपवर्गगतावपि प्रख्याया अविशेषो नास्ति भिन्नवृक्षालम्बनत्वाद्वनमिति प्रत्ययस्य ॥

(उद्योतः) अविच्छेदं व्याचष्टे—अविशेष इति। तस्य गतिरिति। विशेषानवगतिपूर्वं सामान्यस्य शब्दतोऽवगतिरित्यर्थः। अयं भावः—गुणादिभिन्नेष्वनुस्यूतैकाकारप्रतीत्या जातिसिद्धौ तत्र शक्तिग्रहः। शब्दात्तस्या बोधश्च। व्यक्तीनां त्वानन्त्यात्तासु न शक्तिग्रहो, नापि शुद्धानां तासां बोधः, तासां विशेषरूपत्वेन विशेषावगतिप्रसङ्गात्। यथाकृतिरूपादिकं शाब्दबोधे भासते सामान्येन तथा विशेषोपि भासेत, जातेः शक्यत्वे तु तदाश्रयत्वेनाक्षेपादिना सामान्याकृतिरूपादेरेव ग्रहणमिति न दोषः। प्रथमतो बालस्य यद्यपि विशेषव्यक्तावेव शक्तिग्रहस्तथाप्यावापोद्वापन्यायेन व्यक्त्यन्तरे आनयनादि दृष्ट्वा पूर्वजातशक्तिग्रहस्य जात्याश्रयमात्रे व्यवस्थितिरिति तत्त्वम् ॥ वाहादिक्रिया तर्हि कथमत आह—द्रव्यद्वारका इति। आश्रये करणमेव 'जातौ तत्करणमिति भावः। अन्वयबोधे तु बाधज्ञानस्याप्रतिबन्धकत्वान्न तदनुपपत्तिः, जातीत्यादिग्रन्थो वृथेति कश्चित्। **संनिधिमात्रेण।** शक्तिग्रहे व्यक्तावुपलक्षणतामात्रेण ॥ **प्रत्यभिज्ञाप्रत्ययरूपेण।** प्रत्यभिज्ञाविषयेण प्रत्ययेन तदुच्चारितगोशब्दाद्यादृशः प्रत्ययस्तादृश एवैतदुच्चारितादित्येवं प्रत्यभिज्ञाविषयता, सा चैकाकारतां विनाऽनुपपन्नेति ॥ द्वितीयेनाभिधाने सिद्धेप्येकत्वं न सिध्यतीत्याह—**तथा वनमिति। अविशेष इति।** एकरूपत्वमित्यर्थः। वनशब्देन कदाचिदाम्रसमुदायस्य कदाचित् पलाशसमुदायस्य कदाचित् खदिरसमुदायस्य कदाचिदाम्रादिसमुदायस्य प्रतीतेरिति तात्पर्यम् ॥ तदाह—**भिन्नवृक्षेति।**

(७६२ आकृतिशक्तिवार्तिकम् ॥ ४१ ॥)

॥ * ॥ ज्ञायते चैकोपदिष्टम् ॥ * ॥

(भाष्यम्) **ज्ञायते खल्वप्येकोपदिष्टम्। गौरस्य कदाचिदुपदिष्टो भवति। स तमन्यस्मिन्देशेऽन्यस्मिन्कालेऽन्यस्यां च वयोवस्थायां दृष्ट्वा जानाति अयं गौरिति ॥**

(प्रदीपः) **एकोपदिष्टमिति।** एकस्मिन्नुपदिष्टं 'गौरयं त्वया पदा न स्प्रष्टव्य' इत्यादि वस्तु। अथ वैकमुपदिष्टं यस्य तदेकोपदिष्टं सकृदुपदिष्टं गोत्वादि सर्वत्र ज्ञायत इत्यर्थः ॥

(उद्योतः) एकत्वे युक्त्यन्तरमाह—**ज्ञायते चैकेति ॥** आद्यव्याख्यानेध्याहारभयाद्व्याख्यान्तरमाह—**अथ वेति ॥ उपदिष्टमिति।** भावेक्त इत्यर्थः ॥

(आक्षेपभाष्यम्)

कः पुनरस्य विशेषः *प्रख्याविशेषादित्यतः ? ॥

(उद्योतः) भाष्ये—**कः पुनरिति।** अनेनापि प्रख्याऽविशेषस्यैवोपपादनादिति भावः ॥

(समाधानभाष्यम्)

तस्यैवोपोद्बलकमेतत्—'प्रख्याविशेषाद् ज्ञायते चैकोपदिष्टम्' इति ॥

(प्रदीपः) **उपोद्बलकमिति।** उद्गतं बलं प्रत्यक्षं तत्पूर्वकत्वादनुमानस्य उद्बलस्य समीपमनुमानमित्यर्थः। **प्रख्याविशेषादि**त्यनेन प्रत्यक्षं जात्यालम्बनं प्रमाणमुपन्यस्तम्। ततो विप्रतिपन्नप्रतिपादनायानुमानमिह जातिसद्भावे **ज्ञायते चैकोपदिष्टमि**त्यनेनोक्तम्, देशकालावस्थापिण्डान्तरेष्वबाधितप्रत्यभिज्ञाप्रत्ययोदयान्यथानुपपत्त्या सामान्यसद्भावोऽनुमीयत इत्यर्थः। अथ वा बलमुद्दीपयत्युपोद्बलकमुपबृंहकमुच्यते ॥

(उद्योतः) **प्रत्यक्षमिति।** प्रत्यक्षशब्देन शाब्दमप्यत्रोच्यते ॥ **तत्र इति।** तत्रेत्यर्थः ॥ **विप्रतिपन्नेति।** देहात्मप्रत्ययवद्भ्रान्तत्वशङ्केति भाव. ॥ प्रयोगस्तु विमतप्रत्ययो जातिविषयो देशादिभेदेप्यबाधितैकाकारप्रत्ययत्वात् संमतवदिति ॥ **अवस्थेति ॥** अवस्थाकृतभेदोपपादनेन च न व्यक्त्यैवयं विषय प्रति सूचितम् ॥ **प्रत्यभिज्ञाप्रत्ययेति।** तद्विषयप्रत्ययेत्यर्थः ॥ **उपबृंहकमिति।** भ्रान्तत्वाशङ्कानिवर्तनेन प्रमात्वनिर्वाहकस्तर्क इत्यर्थः ॥

(७६३ आकृतिवार्तिकम् ॥ ४२ ॥)

॥ * ॥ धर्मशास्त्रं च तथा ॥ * ॥

(भाष्यम्) एवं च कृत्वा धर्मशास्त्रं प्रवृत्तम् "ब्राह्मणो न हन्तव्यः" "सुरा न पेये"ति, ब्राह्मणमात्रं च न हन्यते, सुरामात्रं च न पीयते । यदि द्रव्यं पदार्थः स्यात्, एकं ब्राह्मणमहत्वा एकां च सुरामपीत्वाऽन्यत्र कामचारः स्यात् ॥

(प्रदीपः) **धर्मशास्त्रं च तथेति** । अनेनैतद्दर्शयति । न सादृश्यैकार्थक्रियाकारित्वादिनिमित्ता भ्रान्ता प्रत्यभिज्ञा सर्वत्रेति ग्राह्यम्, किं तर्हि ? अभिन्नविषयनिमित्ता स्मृतिकाराणामप्यविगीतप्रमाणभावस्मृतोपनिबद्धवचनानां जात्याश्रयेण सर्वव्यवहारप्रवर्तनादित्यर्थः ॥ **एकं ब्राह्मणमिति** । एकस्यैव द्रव्यस्य ब्राह्मणशब्दवाच्यत्वादिति भावः ॥

(उद्द्योतः) **न सादृश्येति** । सादृश्यरूपैकक्रियाकारित्वादिनिमित्तकभ्रमरूपा नेत्यर्थः । अविगीतः प्रमाणभावः प्रमाणत्वं यस्य स्मृतस्य स्मरणस्य पदार्थविषयकस्य तेनोपनिबद्धानि वचनानि यैस्तेषामित्यर्थः । द्रव्यस्य शब्दार्थत्वे ह्येकब्राह्मणवधनिषेधायेव प्रतीयेत। एकः क इति चेद्।? यो यस्य तद्वाक्यश्रवणकाले बुद्धिस्थः स इति गृहाण । जातेः पदार्थत्वे तु न दोष इति तात्पर्यम् ॥ **अन्यत्र कामचार इति** । सर्वेषामिति शेषः ॥ एकैनैकस्याहनने जातः शास्त्रार्थ इत्यन्यब्राह्मणविषये सर्वेषां कामचारः स्यादित्यर्थः ॥

(आक्षेपभाष्यम्)

कः पुनरत्र विशेषः * अव्यपवर्गगतेश्च * इत्यतः ? ॥

(समाधानभाष्यम्)

तस्यैवोपोद्बलकमेतत् 'अव्यपवर्गगतेश्च धर्मशास्त्रं च तथा' इति ॥

(प्रदीपः) **तस्येति** । अव्यपवर्गगतिरभ्रान्ता स्मृतिकाराणामपि तथैव व्यवहारदर्शनादित्यर्थः ॥

(७६४ आकृतिवार्तिकम् ॥ ४३ ॥)

॥ * ॥ अस्ति चैकमनेकाधिकरणस्थं युगपत् ॥ * ॥

(भाष्यम्) अस्ति खल्वप्येकमनेकाधिकरणस्थं युगपल्लभ्यते । किम् ?। आदित्यः । तद्यथा एक आदित्योनेकाधिकरणस्थो युगपदुपलभ्यते ॥

(प्रदीपः) नन्वेकमनेकस्थं कथं भवति नहि देवदत्तो युगपन्मथुरायां स्रुघ्ने च भवतीत्यत आह—**अस्ति चेति** ॥ अवयवी यद्यप्यनेकावयवस्थः तथापि तद्भावे विवादान्नासौ दृष्टान्तत्वेनोपात्तः ॥

(उद्द्योतः) **नन्वेकमिति** । जातिरूपमित्यर्थः ॥ **तद्भावे विवादादिति** । बौद्धादीनामिति शेषः ॥ किं च सामस्त्येन प्रत्यवयवमवयवी नोपलभ्यत इति वैषम्यादपि स न दृष्टान्तित इति भावः ॥

(दृष्टान्तवैषम्यभाष्यम्)

विषम उपन्यासः । नैको द्रष्टा आदित्यमनेकाधिकरणस्थं युगपदुपलभते ॥

(दृष्टान्तान्तरवार्तिकशेषभाष्यम्)

एवं तर्हि—

(७६५ दृष्टान्तवार्तिकम् ॥ ४४ ॥)

॥ * ॥ इतीन्द्रवद्विषयः ॥ * ॥

(भाष्यम्) तद्यथा एक इन्द्रोनेकस्मिन् क्रतुशते आहूतो युगपत्सर्वत्र भवति ॥ एवमाकृतिर्युगपत्सर्वत्र भविष्यति ॥

(प्रदीपः) **इतीन्द्रवद्विषय इति** । एकस्याप्यनेक इति वाक्यशेषः । शब्दप्रादुर्भावेव्ययीभावे कृते वतिः प्रत्ययः ॥ **सर्वत्रेति** । सर्वेषु यागेषु द्रव्यवदङ्गतां प्रतिपद्यत इत्यर्थः ॥

(उद्द्योतः) साकाङ्क्षत्वाद्वाक्यस्याह—**एकस्यापीति** ॥ एकस्याप्यनेक इति पाठः ॥ एकस्यापीन्द्रशब्दस्य यथाऽनेको यागोक्तित्वेन विषय एकबोधज्ञानविषयश्च एकदेशावच्छिन्नानेकयागेषु तथा दर्शनसम्भवात् तथैकस्या अपि जातेरनेको विषय आश्रयतयेत्यर्थः । **अनेकस्थ** इति पाठे एकोपि यथा इन्द्रशब्दोनेकयागस्थ एकस्यापि बोद्धुर्विषयस्तथा जातिरपीत्यर्थः ॥ **अव्ययीभावे इति** । इन्द्रस्य प्रादुर्भाव इत्यर्थः ॥ **सर्वेष्विति** ॥ प्रादुर्भावविषयेन्द्रशब्दरूपा तद्बोध्या वा एका देवता व्रीह्यादिद्रव्यवत्सर्वयागेष्वङ्गतां युगपत्प्रतिपद्यत इत्यर्थः ॥ भाष्येपि **इन्द्रः** इन्द्रशब्दः । **आहूतः** । प्रादुर्भूतः । युगपत्सर्वत्राङ्गं भवतीत्यर्थः ॥

(उपोद्बलकभाष्यम्)

अवश्यं चैतदेवं विज्ञेयम्—एकमनेकाधिकरणस्थं युगपदुपलभ्यत इति ।

(७६६ अनुपपत्तिवार्तिकम् ॥ ४५ ॥)

॥ * ॥ नैकमनेकाधिकरणस्थं युगपदिति चेत्तथैकशेषे ॥ * ॥

(भाष्यम्) यो हि मन्यते—'नैकमनेकाधिकरणस्थं युगपदुपलभ्यत' इति । एकशेषे तस्य दोषः स्यात् । एकशेषेपि नैको वृक्षशब्दोनेकमर्थं युगपदभिदधीत ॥

(प्रदीपः) **एकशेषेपीति** । यद्येकस्यानेकसंबन्धो नाभ्युपगम्यते तदैकः शब्दोऽनेकमर्थं संबन्धाभावान्न प्रत्याययेदित्यर्थः ॥

(उद्द्योतः) **यदीति** । अनेकाधिकरणस्थपदेनानेकसंबन्धो विवक्षित इत्यर्थः । एवं चैकः शब्दो यथाऽनेकत्रार्थे एकेन युगपद् गृह्यते तथा जातिरपीत्यर्थः ॥

(अथाकृतिवादोपपादनम्)

(उपोद्घातकभाष्यम्)

अवश्यं चैतदेवं विज्ञेयमाकृतिरभिधीयत इति ॥

(७६७ अन्यथानुपपत्तिवार्तिकम् ॥ ४६ ॥)

॥ * ॥ द्रव्याभिधाने ह्याकृत्यसंप्रत्ययः [स्तत्रासर्वद्रव्यगतिः] ॥ * ॥

(भाष्यम्) **द्रव्याभिधाने सत्याकृतेरसंप्रत्ययः स्यात् ॥ तत्र को दोषः ? ॥ 'तत्रासर्वद्रव्यगतिः' । तत्रासर्वद्रव्यगतिः प्राप्नोति ॥ असर्वद्रव्यगतौ को दोषः ? । 'गौरनुबन्ध्योऽजोऽग्नीषोमीयः' इति एकः शास्त्रोक्तं कुर्वीत, अपरोऽशास्त्रोक्तम् । अशास्त्रोक्ते च क्रियमाणे विगुणं कर्म भवति । विगुणे च कर्मणि फलानवाप्तिः ॥**

(प्रदीपः) उक्तमेवार्थं समर्थयितुमाह—**द्रव्याभिधाने हीति** । श्रुतिस्मृतिविहितानां सर्वव्यवहाराणामप्रवृत्तिः स्यादित्यर्थः ॥

(उद्द्योतः) भाष्ये—**अपरोऽशास्त्रोक्तमिति** । एकः शब्दः प्रत्यर्थनिवेशित्वादेकं द्रव्यं गोरूपं बोधयेत् तस्य केनचिदालम्भे कृते परैस्तेन वा गवान्तरालम्भेऽशास्त्रार्थः स्यात् । एवं न ब्राह्मणमित्यादावप्येकस्य ब्राह्मणस्यावधो विषयस्तत्रान्यविषये सर्वेषां कामचारेण प्रवृत्तावपि न प्रायश्चित्तं स्यादिति बोध्यम् । सर्वपुरुषान् प्रत्येकव्यक्तेरेव बोधनमित्यभिमानः ॥

(आक्षेपभाष्यम्)

ननु च यस्याप्याकृतिः पदार्थः, तस्यापि यद्यनवयवेन चोद्यते न चानुबध्यते । विगुणं कर्म भवति । विगुणे च कर्मणि फलानवाप्तिः । एका आकृतिरिति च प्रतिज्ञा हीयेत । यश्चास्य पक्षस्योपादाने प्रयोजनम्—एकशेषो न वक्तव्य इति, स चेदानीं वक्तव्यो भवति ॥

(प्रदीपः) **ननु चेति** । सर्वविषया चेदाकृतिश्चोद्यते तदा सर्वव्यक्तिविषयमनुष्ठानं विना वैगुण्यमेव स्यादित्यर्थः ॥ अथानुष्ठानसिद्ध्यर्थमेकद्रव्यविषयमेव कर्म क्रियते तत्राप्युच्यते—**एकाकृतिरिति चेति** । चशब्दस्तुशब्दस्यार्थे, वक्ष्यमाणार्थापेक्षया समुच्चये वा ॥ **स चेदानीमिति** । एकत्वे जातेरेकशब्दप्रवृत्तेः सिद्धत्वादेकशेषारम्भः प्रत्याख्यायते । अनेकत्वे त्वारब्धव्य एवैकशेष इत्यर्थः ॥

(उद्द्योतः) **अथानुष्ठानेति** । अयं भावः—जातेः साक्षादनुबन्धनाद्यसम्भवाद् व्यक्तिद्वारा तद्वाच्यं तत्रानुष्ठानसिद्ध्यर्थमेकप्रयोगे एकव्यक्तिद्वारकमेव तदाश्रीयते । तत्राकृतेरेकत्वे विनिगमनाविरहात्सर्वव्यक्तिद्वारकमेव तदाश्रीयेत । आकृतेरनेकत्वे तु प्रतिज्ञाहानिरिति ॥ पूर्वारुच्याऽस्यावतारणाच्चशब्दोऽनुपपन्नोऽत आह—तुशब्दस्यार्थे इति ॥

(समाधानभाष्यम्)

एवं तर्ह्यनवयवेन चोद्यते, प्रत्येकं च परिसमाप्यते । यथा आदित्यः ॥

(प्रदीपः) **एवं तर्हीति** । सर्वाभिर्व्यक्तिभिः संबन्धस्य तुल्यत्वात् सर्वत्रैवाभिन्नबुद्ध्युत्पादनात् प्रत्येकं परिसमाप्तत्वादेकस्मिन्नपि द्रव्ये तत्कर्म क्रियमाणं जातौ कृतमेव भवतीत्यर्थः ॥ **यथादित्य इति** । प्रतिदेशं यथा सर्वात्मनादित्य उपलभ्यते तथा जातिरपीत्यर्थः ॥

(उद्द्योतः) भाष्ये—**अनवयवेनेति** । जात्याश्रया व्यक्तिविशेषा अवयवा इत्युच्यते ॥ **अनवयवेन** । व्यक्तिविशेषानालम्बनेनेत्यर्थः ॥ नन्वाश्रयभेदात्तद्भेदोऽत आह—**सर्वाभिरिति** । भेदकाभावान्न भेद इति भावः । प्रत्यक्षविरोधाद् धर्मिग्राहकमानविरोधाच्च भेदानुमानमसङ्गतमिति भावः ॥ नन्वादित्यस्य प्रत्येकं समाप्त्यभावेन दृष्टान्तासंगतिं मत्वाह—**प्रतिदेशमिति** ॥

(आक्षेपभाष्यम्)

ननु च यस्यापि द्रव्यं पदार्थः, तस्याप्यनवयवेन चोद्यते, प्रत्येकं च परिसमाप्यते ॥

(प्रदीपः) **ननु चेति** । द्रव्येपि पदार्थे जातेरनभिधेयाया उपलक्षणत्वेनाश्रयणात्परित्यक्तभेदं द्रव्यमात्रं विशिष्टजातियुक्तं शब्देनोच्यते ॥ **प्रत्येकं च परिसमाप्यत इति** । शास्त्रमित्यध्याहारः । अथ वा जातिरुपलक्षणभूता प्रत्येकं परिसमाप्यतइति व्याख्येयम् ॥ **एकशेषस्त्वयेति** । जात्युपलक्षितस्य द्रव्यस्य शब्देनाभिधाने सत्यभिधेयानेकत्वेनाऽनेकशब्दत्वप्रसङ्गादित्यर्थः ॥

(उद्द्योतः) **अनभिधेयाया इति**—शक्यतावच्छेदकमशक्यमेवेत्यर्थः । यद्वा प्राधान्येनानभिधेयाया इत्यर्थः ॥ **परित्यक्तभेदमिति** । परित्यक्तावान्तरभेदमित्यर्थः ॥ ननु द्रव्यस्य प्रत्येकं समाप्तेः प्रकृतेनुपयोगोऽत आह—**शास्त्रमिति** ॥ **शब्देनाभिधाने इति** । प्राधान्येनेत्यर्थः ॥

(आकृतिवादिभाष्यम्)

एकशेषस्त्वया वक्तव्यः ॥

(द्रव्यवादिभाष्यम्)

त्वयापि तर्हि द्विवचनबहुवचनानि साध्यानि ॥

(प्रदीपः) **त्वयापीति** । जातेरेकत्वाद् द्वित्वबहुत्वनिबन्धनानि द्विवचनबहुवचनानि न सिध्यन्तीति भावः ॥

(७६८ आकृतिवार्तिकम् ॥ ४७ ॥)

॥ * ॥ चोदनायां चैकस्योपाधिवृत्तेः ॥ * ॥

(भाष्यम्) चोदनायां चैकस्योपाधिवृत्तेर्मन्यामहे आकृतिरभिधीयत इति । 'आग्नेयमष्टाकपालं निर्वपेत्' । एकं निरुप्य द्वितीयस्तृतीयश्च निरुप्यते । यदि च द्रव्यं पदार्थः स्यादेकं निरुप्य द्वितीयस्य तृतीयस्य च निर्वपणं न प्रकल्पेत ॥

(प्रदीपः) एवं भाष्यकारेण पक्षयोः साम्यं दर्शितम् । वाक्यकारस्तु जातिपक्षाश्रयणस्य प्रयोजनानि समुच्चयेनाचष्टे—**चोदनायां चैकस्येति** । सामान्यस्याग्नेयादेः ॥ **उपाधिवृत्तेरिति** । अष्टाकपालत्वादिरुपाधिः तस्य वृत्तिः प्रवृत्तिः । एतदुक्तं भवति—यदि आग्नेयादिशब्देन सामान्यमभिधीयते तदा तेनाशेषद्रव्याणामाक्षेपात्प्रतिद्रव्यमष्टाकपालत्वमुपाधिर्युज्यते द्रव्ये तु पदार्थे एकेनैव यजमानेन सकृदेवाष्टाकपालः पुरोडाशो निरुप्येत नान्येन नाप्यन्यदेत्यर्थः ॥

(उद्द्योतः) नन्वेवं चोदनायां चैकस्येति चोनुपपन्न इत्यत आह—**वाक्यकार इति** ॥ **प्रयोजनानि** । प्रयोजनान्तराणि ॥ **समुच्चयेनेति** । द्रव्याभिधाने ह्याकृत्यसंप्रत्ययः इत्यनेन समुच्चय इति बोध्यम् । एकस्याग्नेयादेर्य उपाधिरष्टाकपालत्वादिस्तस्य पुनः पुनः प्रवृत्तेरिति वार्तिकार्थः । समासश्चार्थस्यात् ॥ एकस्येति व्याचष्टे-**सामान्यस्येत्यादि** ॥ अष्टाकपालत्वादीत्यादिपदेन निर्वापः । अत एव भाष्ये स एव दर्शित एकं निरुप्येत्यादिना ॥ **प्रवृत्तिरिति** । पुनःपुनर्वृत्तिरित्यर्थः ॥

(आक्षेपभाष्यम्)

कः पुनरेतयोर्जातिचोदनयोर्विशेषः ? ॥

(प्रदीपः) **कः पुनरिति** । **'गौरनुबन्ध्यः'** इति **'आग्नेयमष्टाकपालम्** इति चानयोरित्यर्थः ॥

(समाधानभाष्यम्)

एका निर्वृत्तेन, अपरा निर्वर्त्येन ॥

(प्रदीपः) **एका निर्वृत्तेनेति** । निष्पन्नो हि पशुर्यागसाधनायोपादीयते ॥ **अपरा निर्वर्त्येनेति** । आग्नेयोष्टाकपालश्चोदनयैवोत्पाद्यते न तु चोदनायाः पूर्वं निष्पन्न इत्यर्थः । तत्र निर्वृत्ते भेदाग्रहणात् द्रव्यान्तरेऽपि प्रवृत्तिः स्यान्न तु निर्वर्त्ये सादृश्याग्रहणादित्यवश्याश्रयणीया जातिः ॥

(उद्द्योतः) उत्पाद्यतइति । उत्पाद्यत्वेन बोध्यत इत्यर्थः ॥ ननु प्रकारभेदेपि द्वितीयोपन्यासे किं बीजमत आह—**तत्रेति** ॥ रूपसामान्याद्वासिद्धं इति अद्दुडणितिसूत्रस्थभाष्यरीत्या निष्पन्ने 'इदम् अभिधेयं नेदं' इति विवेकाग्रहादित्यर्थः ॥ ननु तत्राप्युक्तरीत्यैव प्रवृत्तिः स्यादत आह—**सादृश्येति** । तस्य ससंबन्धिकत्वेन प्रतियोग्यन्तरानुपस्थितेरिति भावः ॥

(इत्याकृतिवादोपपत्तिः ॥)

(अथ व्यक्तिवादोपपत्तिः ॥)

(७६९ व्यक्तिवादिवार्तिकम् ॥ ४८ ॥)

॥ * ॥ द्रव्याभिधानं व्याडिः ॥ * ॥

(भाष्यम्) द्रव्याभिधानं व्याडिराचार्यो न्याय्यं मन्यते द्रव्यमभिधीयत इति ॥

(प्रदीपः) **द्रव्याभिधानमिति** । जातेर्वृत्तिविकल्पासहत्वेनाभावं मन्यमानो व्याडिर्द्रव्यमेव शब्देनाभिधीयत इति मन्यते ॥

(उद्द्योतः) ननु व्यक्तिशक्तावानन्त्यव्यभिचारयोः सत्वात् जातौ शक्तिरित्याशङ्क्य जातिरेव नास्तीत्याह—**वृत्तिविकल्पेति** । जातिर्न तावद्द्रव्येषु व्यासज्यवृत्तिः, एकाश्रयनाशेऽप्रतीत्यापत्तेः । किं च गामालभेतेत्यादिनोदनासु सर्वद्रव्यालम्भापत्तिः । प्रत्येकसमाप्तौ तु द्रव्यान्तरे तदनापत्तिस्तत्रापि सत्त्वे एकाकृतिरिति प्रतिज्ञाहानिरित्यर्थः । तत्तत्संस्थानाद्युपलक्षितमधिष्ठानचैतन्यमेव द्रव्यमिति नानन्त्यव्यभिचाराविति तात्पर्यम् ॥

(७७० व्यक्तिशक्तिसाधकवार्तिकम् ॥ ४९ ॥)

॥ * ॥ तथा च लिङ्गवचनसिद्धिः ॥ * ॥

(भाष्यम्) एवं च कृत्वा लिङ्गवचनानि सि-

ख्यानि भवन्ति । ब्राह्मणी ब्राह्मणः ब्राह्मणौ ब्राह्मणा इति ।

(७७१ व्यक्तिशक्तिसाधकवार्तिकम् ॥ ५० ॥)

॥ * ॥ चोदनासु च तस्यारम्भात् ॥ * ॥

(भाष्यम्) चोदनासु च तस्यारम्भान्मन्यामहे द्रव्यमभिधीयत इति । 'गौरनुबन्ध्योऽजोऽग्नीषोमीय' इति ॥ आकृतौ चोदितायां द्रव्ये आरम्भणालम्भनप्रोक्षणविशसनादीनि क्रियन्ते ॥

(प्रदीपः) आकृतौ चोदितायामिति । आकृतिवादिपक्षे शब्देनाकृतिश्चोद्यते द्रव्ये तु कार्यं प्रवर्तते । अयुक्तं चैतत् । नह्यन्यचोदनेन्यस्य कार्ये क्रियमाणे यथोक्तं कृतं भवति । तस्माद् द्रव्यमेव शब्देनोच्यत इति न्याय्यम् ॥

(उद्द्योतः) चोदनास्विति । प्रवर्तकवाक्येषु तस्य द्रव्यस्यारम्भणात् । इदमुपलक्षणमारम्भणालम्भनादिकरणादित्यर्थः । तत्रारम्भणं क्रयो बन्धनं वा ॥ जातिवादे दूषणमाह भाष्ये—आकृतौ चोदितायामिति । कर्मसंबन्धित्वेन चोदितायामित्यर्थः ॥ तच्छेषपूरणेन व्याचष्टे—अयुक्तमित्यादिना ॥

(७७२ अनुपपत्तिवार्तिकम् ॥ ५१ ॥)

॥ * ॥ न चैकमनेकाधिकरणस्थं युगपत् ॥ * ॥

(भाष्यम्) न खल्वप्येकमनेकाधिकरणस्थं युगपदुपलभ्यते । नह्येको देवदत्तो युगपत्स्रुघ्ने भवति मथुरायां च ॥

(प्रदीपः) न चैकमिति । न च हेतुरहितेनादित्यदृष्टान्तेन साध्यसिद्धिर्भवति, देवदत्तदृष्टान्तेन विपर्ययस्यापि साधनात् ॥

(उद्द्योतः) तत्रैव दूषणान्तरम्—न चैकमिति ॥ विपर्ययस्यापीति । सत्प्रतिपक्षसंभवादित्यर्थः ॥ एवं चानेकद्रव्यगतैका जातिरभ्युपगन्तुमेव न शक्यत इति भावः ॥

(७७३ अनिष्टापत्तिवार्तिकम् ॥ ५२ ॥)

॥ * ॥ विनाशे प्रादुर्भावे च सर्वं तथा स्यात् ॥ * ॥

(भाष्यम्) किम्? । विनश्येच्च प्रादुष्याच्च ॥ 'श्वा मृतः' इति श्वा नाम लोके न प्रचरेत् । 'गौर्जात' इति सर्वं गोभूतमनवकाशं स्यात् ।

(प्रदीपः) श्वा मृत इति । अभिव्यञ्जकविनाशे जातेस्तिरोभावात् पिण्डान्तरे श्वेति प्रत्ययो न स्यात् । शतप्रत्यय इवैकापाय इत्यर्थः । यद्वा आश्रयापाये आश्रितस्याप्यपायः अवयवापाये अवयविन इवेति जातेर्विनाशप्रसङ्ग इत्यर्थः ॥ गौर्जात इति । जातेन गोपिण्डेन गोत्वमभिव्यक्तं तच्च सर्वाश्रयवर्तीति एकगोपिण्डप्रत्यक्षत्वे सर्वगोपिण्डप्रत्यक्षत्वप्रसङ्गः ॥ अनवकाशमिति । पदार्थान्तरप्रत्ययस्यावकाशाभावात् । अथ वा सर्ववस्तुव्यापि गोत्वमेष्टव्यम् । अन्यथा

नायाति न च तत्रासीदस्ति पश्चान्न चांशवत् ।
जहाति पूर्वं नाधारमहो व्यसनसन्ततिः ॥' इति

दोषापत्तिः । ततश्च—

व्यक्त्यैवैकत्र सा व्यक्ताऽभेदात्सर्वत्रगा यदि ।
जातिर्दृश्येत सर्वत्र ...''

इति सर्वेषु पदार्थेषु गोप्रत्ययप्रसङ्गः ॥

(उद्द्योतः) ननु जातेर्नित्यत्वात्कथं नाशादि । किं चैकनाशेपि व्यक्त्यन्तरेणाभिव्यक्तजात्या श्वा प्रचरेदेवेत्यत आह—अभिव्यञ्जकेति । व्यासज्यवृत्तिर्जातिः सर्वव्यक्तिभिः संभूयाभिव्यज्यत इति मते इदं दूषणम्, जातेर्नाशश्च तिरोभाव एवेत्यर्थः । एवं च श्वा नाम लोके न संचरेदिति भाष्यस्य व्यक्त्यन्तरे श्वप्रत्ययवि-

षयो न सञ्चरेद् न स्यादित्यर्थः। एवं विनाशपदं व्यक्तिषु ध्वंसपरं तथेति परामृष्टमाकृतौ तिरोधानपरमित्ययुक्तमिति मत्वाह—**यद्येति**। आविद्यको धर्मविशेषो जातिरिति भावः॥ **जातेनेति**। ध्यासज्यसर्वाश्रयवृत्तिगोत्वं सर्वाश्रयज्ञानैरभिव्यङ्ग्यमन्यथा गोत्वज्ञानमेव न स्यादित्यर्थः। अस्तु तर्हि तत्प्रत्यक्षत्वाय तदाश्रयसर्वस्य प्रत्यक्षत्वमत आह—भाष्ये—**अनवकाशमिति**। अर्थान्तरप्रत्ययावकाशरहितं गोर्मूर्तं गोत्वप्रत्यक्षाय गोरूपं वस्तु सर्वं प्रत्यक्षं स्यात्। गोव्यक्तीनामनन्तत्वादनवकाशत्वमित्यर्थः॥ न विद्यतेऽवकाशो यस्मादिति बहुव्रीहिरिति तात्पर्यम्। अत्र पक्षेऽध्याहारक्लेशात्पक्षान्तरमाह—**अथ वेति**॥ **नायातीति**। उत्पन्ने गवि व्यक्त्यन्तराद्यायातीति न शक्यं वक्तुं, तस्या निष्क्रियत्वात्। **न यातीति** पाठे उत्पन्नव्यक्तिं व्यक्त्यन्तरादागत्य न प्राप्नोतीत्यर्थः॥ **न च तत्रासीदिति**। प्रागाश्रयाभावादित्यर्थः॥ तत्रैव हेतुमाह—**अस्ति पश्चादिति**। यतः पश्चादेवास्ति अतः पूर्वं नासीदित्यर्थः। एतेन मा यासीत् मा च भूत् तत्र गोत्वमिति परास्तम्। ननु सक्रियत्वमङ्गीकृत्यांशेनागमनमस्त्वत आह—**न चांशवदिति**। निरवयवत्वेनांशाभावादित्यर्थः॥ ननु पूर्वमाधारं त्यक्त्वात्रैवायातीत्यत आह—**जहातीति**। पूर्वत्रापि प्रतीतेरिति भावः। तस्मात्सर्वगैकेति वाच्यं ततश्च कयाचिद्व्यक्त्यैव व्यक्ता साऽभेदात्सर्वगेति वाच्यम्। ततश्च सर्वत्र दृश्येत तदाह—**सर्वेष्विति**। अत्र पक्षे गोभूतमभिव्यक्तगोत्वेन व्याप्तं तुल्यव्यक्तित्वेन जात्यन्तरावकाशरहितं सर्वं स्यादिति भाष्यार्थः॥ जातिसंकरप्रसङ्गश्चेत्यपि बोध्यम्।

(७७४ व्यक्तिवादिवार्तिकम्॥ ५३॥)

॥ * ॥ अस्ति च वैरूप्यम्॥ * ॥

(भाष्यम्) **अस्ति खल्वपि वैरूप्यम् 'गौश्च गौश्च' खण्डो मुण्ड इति॥**

(प्रदीपः) **अस्ति च वैरूप्यमिति**। तस्माद् द्रव्यमेवास्तु न तु सामान्यम्। नह्येकस्य भेदाभेदौ विरुद्धौ उपपद्येते इत्यर्थः। एकार्थक्रियाकारित्वादिनिमित्तस्तु प्रत्यभिज्ञाप्रत्ययः॥ **गौश्चेति**। भेदाधिष्ठानः समुच्चयः सामान्यस्यैकत्वाभिधेयत्वयोर्न स्यादित्यर्थः।

(उद्द्योतः) **नहीति**। एवं च तत्तच्छब्दप्रतिपाद्ये एकस्मिन् विरुद्धधर्मोपपत्तेरभावाद्द्रव्यमेव पदार्थ इति भावः॥

भाष्ये **गौश्च गौश्चे**त्यनेनाभिप्रेतं वैरूप्यमुपपादयति—**भेदेति**। एवं खण्डो गौर्मुण्डो गौरिति च न स्यादिति भावः॥ **प्रत्यभिज्ञाप्रत्ययस्तद्विषयः**॥

(७७५ व्यक्तिवादिवार्तिकम्॥ ५४॥)

॥ * ॥ तथा च विग्रहः॥ * ॥

(भाष्यम्) **एवं च कृत्वा विग्रह उपपन्नो भवति—गौश्च गौश्चेति।**

(उद्द्योतः) भाष्येऽस्ति च वैरूप्यमिति वाक्यस्थचशब्दं व्याचष्टे—**तथा च विग्रह इति**। एकार्थत्वे पर्यायाणामिव सहप्रयोगो न स्यादिति भावः॥

(७७६ व्यक्तिवादिवार्तिकम्॥ ५५॥)

॥ * ॥ व्यर्थेषु च मुक्तसंशयम्॥ * ॥

(भाष्यम्) **व्यर्थेषु च मुक्तसंशयं भवति। आकृतावपि पदार्थे एकशेषो वक्तव्यः॥ अक्षाः पादा माषा इति॥**

(प्रदीपः) **आकृतावपीति**। यदर्थं आकृतिपक्षपरिग्रहः तदेव न सिध्यति नहि शकटाक्षदेवनाक्षादिष्वेकाकृतिसद्भावः॥

(उद्द्योतः) भाष्ये—**व्यर्थेष्विति**। विजातीयानेकार्थसरूपशब्देष्वित्यर्थः॥ **मुक्तसंशयमिति**। एकशेषाङ्गीकरणमिति शेषः॥

(इति व्यक्तिशक्तिवादोपपत्तिः॥)

(७७७ आकृतिवादिवार्तिकम्॥ ५६॥

॥ * ॥ लिङ्गवचनसिद्धिर्गुणस्यानित्यत्वात्॥ * ॥

(भाष्यम्) **लिङ्गवचनानि सिद्धानि भवन्ति। कुतः? गुणस्यानित्यत्वात्। अनित्या गुणा अपायिन उपायिनश्च॥**

(प्रदीपः) इदानीमाकृतिवादी दोषान् परिहर्तुमाह—**लिङ्गेति**। आकृतिसद्भावः पूर्वमेव प्रत्यक्षानुमानागमप्रवृत्तिभिः प्रतिपादितः। सर्वगतत्वेपि पदार्थानां विचित्रशक्तियोगात् कश्चित्पदार्थः कांचिदेवाकृतिमभिव्यनक्ति न तु सर्वां सर्वः। गुणाश्चात्र द्वित्वस्त्रीत्वादयो विवक्षिताः। तैश्चाकृतेरेकार्थसमवायलक्षणः संबन्ध इत्याकृतावपि पदार्थे लिङ्गसंख्यासिद्धिरित्यर्थः॥ **अनित्या इति**। कदाचित्स्त्रीत्वयुक्तेन पिण्डेनाकृतिर्व्यज्यते कदाचित्पुंस्त्वयुक्तेन कदाचिदेकाधारस्था प्रतिपाद्यते कदाचिदनेकाधारस्थेत्यर्थः॥

(उद्द्योतः) जात्यभावो व्याडिमते उक्तस्तं निरस्यति—**आकृतिसद्भाव इति**॥ अथ वेत्यादिना व्याख्यातं **सर्वं गोभूत**मित्यादिदोषं परिहरति—**सर्वगतत्वेपीति**॥ संकरोपि न, परस्परपरिहारेण भिन्नवस्तुनिष्ठानामेकत्र स्थितेः संकरत्वात् न स गोत्वादीनामिति भावः॥ आद्यव्याख्यारीत्या दोषस्तु जातेः प्रत्येकं परिसमाप्त्यङ्गीकारेण सङ्करः। एकैकव्यक्तिव्यङ्ग्यत्वाच्च न **विनाशे**त्यादिदोषः॥ **न तु सर्वामिति**। यथात्मनां व्यापकत्वेपि कस्मिंश्चित् शरीरे कश्चिदेवात्मा स्फुरति न तु सर्वः सर्वत्र तद्वदित्यर्थः॥ **एकार्थसमवायेति**। तेन च निमित्तेन जातौ लिङ्गसंख्यारोप इत्यर्थः॥ भाष्ये—**गुणस्येति**। जातावेकवचनम्॥ **अनित्या इति**। अनियता इत्यर्थः। अपायित्वोपायित्वाभ्यामनियतत्वमेव भाष्ये दर्शितम्॥

(आक्षेपभाष्यम्)

किं य एते शुक्लादयः?।

(प्रदीपः) किं च एत इति । ते हि गुणत्वेन प्रसिद्धाः । न च तदनित्यत्वं लिङ्गवचनसिद्धौ हेतुरुपपद्यत इति प्रश्नः ॥

(समाधानभाष्यम्)

नेत्याह । स्त्रीपुंनपुंसकानि सत्त्वगुणाः । एकत्वद्वित्वबहुत्वानि च । कदाचिदाकृतिरेकत्वेन युज्यते, कदाचिद्द्वित्वेन, कदाचिद्बहुत्वेन, कदाचित्स्त्रीत्वेन कदाचित्पुंस्त्वेन कदाचिन्नपुंसकत्वेन ॥

(प्रदीपः) प्रकरणादर्थनिश्चय इत्याह—नेत्याहेति ॥

(आक्षेपभाष्यम्)

भवेल्लिङ्गपरिहार उपपन्नः, वचनपरिहारस्तु नोपपद्यते । यदि हि कदाचिदाकृतिरेकत्वेन युज्यते कदाचिद्द्वित्वेन कदाचिद्बहुत्वेन, एका आकृतिरिति च प्रतिज्ञा हीयेत । यश्चास्य पक्षस्योपादाने प्रयोजनमुक्तम् 'एकशेषो न वक्तव्यः' इति, स च इदानीं वक्तव्यो भवति ॥

(प्रदीपः) वचनपरिहारस्त्विति । लिङ्गपरिहारे न किंचिद् दुष्यति, वचनपरिहारे त्वभिधीयमाने एकाकृतिरिति प्रतिज्ञाहानिः द्वित्वबहुत्वसंबन्धस्याप्यभ्युपगमात् । द्विवचनबहुवचनवदनेकशब्दत्वमपि प्राप्नोतीत्येकशेषोपि वक्तव्य इत्यर्थः ॥

(उद्द्योतः) बहुवचनवदिति । आश्रयगतसंख्यावदाश्रयबोधे इवानेकशब्दत्वमपि प्राप्नोतीत्यभिमानः ॥

(भाष्यम्) एवं तर्हि

(७७८ न्यासान्तरवार्तिकम् ॥ ५७ ॥)

॥ * ॥ लिङ्गवचनसिद्धिर्गुणविवक्षानित्यत्वात् ॥ * ॥

(भाष्यम्) लिङ्गवचनानि सिद्धानि भवन्ति । कुतः ? । गुणविवक्षाया अनित्यत्वात् । अनित्या गुणविवक्षा । कदाचिदाकृतिरेकत्वेन विवक्षिता भवति कदाचिद् द्वित्वेन कदाचिद्बहुत्वेन, कदाचित्स्त्रीत्वेन कदाचित्पुंस्त्वेन कदाचिन्नपुंसकत्वेन ॥

(प्रदीपः) गुणविवक्षानित्यत्वादिति । स्वत आकृतेरेकत्वं द्रव्यगतद्वित्वबहुत्वविवक्षायां तु द्विवचनबहुवचने भवतः । आश्रयधर्मैराश्रितानां व्यपदेशः । यथा संपन्नो यवो विनष्टो यव इति संपत्तिविनाशाभ्यां द्रव्यगताभ्यां जातिर्व्यपदिश्यते तथा लिङ्गसंख्याभ्यामपीत्यर्थः ॥

(उद्द्योतः) जातिर्व्यपदिश्यत इति । यव इत्येकवचनेन तत्र जातिप्राधान्यावगमादिति भावः ॥ एवं चारोपितद्वित्वादिना न प्रतिज्ञाहान्यादीति तात्पर्यम् ॥

(आक्षेपभाष्यम्)

भवेल्लिङ्गपरिहार उपपन्नः । वचनपरिहारस्तु नोपपद्यते । यदि कदाचिदाकृतिरेकत्वेन विवक्षिता भवति कदाचिद्द्वित्वेन कदाचिद्बहुत्वेन, एका आकृतिरिति च प्रतिज्ञा हीयेत । यश्चास्य पक्षस्योपादाने प्रयोजनमुक्तमेकशेषो न वक्तव्य इति । स चेदानीं वक्तव्यो भवति ॥

(प्रदीपः) भवेदिति । अभ्युपगमविरोधाभावात् । वचनपरिहारस्त्वभ्युपगमं विरुणद्धि द्वित्वबहुत्वयोगेभ्युपगतैकत्वहानादनेकशब्दत्वप्रसङ्गाच्चेत्यर्थः ॥

(उद्द्योतः) अभ्युपगममिति । गौण्यप्युत्तरा संख्या पूर्वां संख्यां बाधत इति भावः ॥

(समाधानभाष्यम्)

लिङ्गपरिहारश्चापि नोपपद्यते । किं कारणम् ? । आविष्टलिङ्गा जातिर्यल्लिङ्गमुपादाय प्रवर्तते । उत्पत्तिप्रभृत्या विनाशात्तल्लिङ्गं न जहाति ॥

(प्रदीपः) लिङ्गपरिहारश्चापीति । विशेषणानां चाजातेरित्यत्रोक्तमाविष्टलिङ्गा जातिरिति । ततश्चैकमेवाश्रयगतं लिङ्गमुपादत्ते सर्वदा जातिः यथा ग्राम्यपशुजातयः संघे स्त्रीत्वमेवोपाददते गाव इमा इति, अन्यास्तु पुंस्त्वमेव ब्राह्मणा इमे इति यथेत्यर्थः ॥

(उद्द्योतः) आविष्टलिङ्गेति । स्वाश्रयेनेकलिङ्गसत्त्वेपि स्वयं यत् किंचिदेकमेवोपादत्ते तथा चानेकलिङ्गत्वासिद्धिरिति भावः ॥ उक्तमेवार्थं दृष्टान्तेनाह—ततश्चेति । न चैवं लिङ्गस्यासिद्धिः, कुतः, ब्राह्मणीशब्दवाच्यया जात्या आश्रयगतं स्त्रीत्वमेवोपादीयते ब्राह्मणशब्दवाच्यया पुंस्त्वमेवेति व्यवस्थासंभवादिति बाच्यम् । ब्राह्मणी पदार्थः, इयं ब्राह्मणव्यक्तिरिदं ब्राह्मणवस्तु ब्राह्मणी दारा इत्यादिव्यवहारानुपपत्तेरित्याशयात् ॥

(समाधानोपसंहारभाष्यम्)

तस्मान्न वैयाकरणैः शक्यं लौकिकं लिङ्गमास्थातुम्, अवश्यं कश्चित्स्वकृतान्त आस्थेयः ॥

(प्रदीपः) तस्मादिति । सिद्धान्तवादी युक्तं पक्षमाश्रयति—लौकिकमिति । स्तनकेशादिसंबन्ध इत्यर्थः । तस्मिन्नाश्रीयमाणे लिङ्गान्तरेण संबन्धो न स्यात् ॥ तस्मात्स्वसिद्धान्तव्यवस्थाश्रीयते ॥

(उद्द्योतः) सिद्धान्तवादीति । आकृतिवादीत्यर्थः ॥ स्तनकेशादीति । केशो भगम् ॥ लिङ्गान्तरेणेति । ब्राह्मणी दारा इत्यादौ द्रव्यद्वारा जातेर्लिङ्गान्तरेण योगो न स्याद् तटस्तटीत्यादौ च कस्यापि लिङ्गस्य योगो न स्यादिति भावः । शब्दविशेषापेक्षया तु जातेराविष्टलिङ्गत्वोक्तिरिति तात्पर्यम् ॥ भाष्ये—कृतान्तः । सिद्धान्तः ॥

(आक्षेपभाष्यम्)

कोऽसौ स्वकृतान्तः ? ।

(७७९ समाधानवार्तिकम् ॥ ५८ ॥)

॥ * ॥ संस्त्यानप्रसवौ लिङ्गम् ॥ * ॥

(भाष्यम्) संस्त्यानप्रसवौ लिङ्गमास्थेयौ ॥

(आक्षेपभाष्यम्)

किमिदं संस्त्यानप्रसवाविति ? ॥

(उद्द्योतः) किमिति । संस्त्यानप्रसवशब्दयोः कोर्थ इति प्रश्नः ॥

(७८० समाधानवार्तिकम् ॥ ५९ ॥)

॥ * ॥ संस्त्याने स्त्यायतेर्ड्रट् स्त्री सूतेः सप् प्रसवे पुमान् ॥ * ॥

(उद्द्योतः) उत्तरं—संस्त्यान इति । संस्त्यानेऽभिधेये स्त्यायतेर्ड्रट्प्रत्ययान्तस्त्रीशब्द इत्यर्थः । सूतेः सप् सकारस्य पकार इत्यर्थः ।। प्रसवेभिधेये पुमानिति शब्दः ॥

(आक्षेपभाष्यम्)

ननु च लोकेपि स्त्यायतेरेव स्त्री, सूतेश्च पुमान् ॥

(समाधानभाष्यम्)

अधिकरणसाधना लोके स्त्री—स्त्यायत्यस्यां गर्भ इति, कर्तृसाधनश्च पुमान् सूते पुमानिति । इह पुनरुभयं भावसाधनं स्त्यानं प्रवृत्तिश्च ॥

(उद्द्योतः) गर्भः शुक्रं स्त्यायति शोणितेन संघीभवतीत्यर्थः । सूते शुक्रं त्यजति योनिरूपे आधारे ॥ स्त्यानमपचयः । प्रवृत्तिर्वृद्धिः ॥

(आक्षेपभाष्यम्)

कस्य पुनः स्त्यानं स्त्री, प्रवृत्तिर्वा पुमान् ? ।

(समाधानभाष्यम्)

गुणानाम् ॥

केषाम् ? ।

शब्दस्पर्शरूपरसगन्धानाम् । सर्वाश्च पुनर्मूर्तय एवमात्मिकाः संस्त्यानप्रसवगुणाः शब्दस्पर्शरूपरसगन्धवत्यः । यत्राल्पीयांसो गुणाः तत्रावरतस्त्रयः शब्दः स्पर्शो रूपमिति । रसगन्धौ न सर्वत्र । प्रवृत्तिः खल्वपि नित्या । नहीदं कश्चिदपि स्वस्मिन्नात्मनि मुहूर्तमप्यवतिष्ठते, वर्धते यावदनेन वर्धितव्यमपचयेन वा युज्यते । तच्चोभयं सर्वत्र ॥

(प्रदीपः) गुणानां सत्त्वरजस्तमःपरिणामरूपाणां शब्दादीनां वृद्धिह्रासमध्यस्थावस्थाः शब्दैकगोचराः लिङ्गत्वेन परिगृह्यन्ते । आत्मनस्त्वपरिणामिरूपत्वादप्रवृत्तिधर्मत्वेप्यन्यप्रवृत्त्यनुयायित्वाल्लिङ्गयोगः ॥

(उद्द्योतः) शब्देत्यादि । इदमुपलक्षणं सत्त्वादिकार्यमात्रस्येति बोध्यम् ॥ उपलक्षणत्वं ध्वनयन्नुक्तयोर्व्याप्तिमाह—सर्वाश्चेति ॥ मूर्तयः पदार्थाः ॥ एवमात्मिका इत्यस्य विवरणं संस्त्यानेत्यादिगन्धवत्य इत्यन्तम् पृथिव्यपेक्षयाऽप्सु अल्पे, अप्पृथिवीभ्यां तेजसि अल्पे इत्यल्पीयांसः । त्रय इत्युपलक्षणं वायौ रूपाभावात्, आकाशे स्पर्शस्याप्यभावाच्च ॥ वस्तुतस्तेजोबन्नरूपाणां सर्वमूर्तीनां त्रिवृत्करणमात्राभिप्रायेणेदमुक्तम्, वाय्वाकाशशब्दवाच्ययोर्लिङ्गव्यवहारस्तु ईश्वर इव स्वकार्यतेजोबन्नगतोपचयारोपेणेति बोध्यम् ॥ प्रवृत्तिः खल्वपीति । परिणाम इत्यर्थः । प्रतिक्षणपरिणामित्वाद्वस्तूनाम् ॥ नहीति । अस्यावतिष्ठत इत्यनेनान्वयः, किंतु परिणमत एवेति शेषः ॥ तच्चोभयमिति । वृद्ध्यपचयरूपमित्यर्थः ॥ सर्वत्रेति । पदार्थ इत्यर्थः । सर्वदेत्यपि बोध्यम् ॥ कैयटे गुणानामिति शब्दादीनामित्युपलक्षणं सत्त्वकार्यमात्रस्य । अन्यथा शब्दे लिङ्गव्यवहारो न स्यात् ॥ तासां लिङ्गत्वे प्रमाणं दर्शयति—शब्दैकेति । शब्दजन्यबोधविषया इत्यर्थः ॥ अप्रवृत्तिधर्मत्वेपि । स्वतो लिङ्गरहितत्वेपि ॥ अन्यप्रवृत्त्यनुयायित्वादिति । परिणामवदन्यतादात्म्याध्यासेन तत्परिणामानुयायित्वादित्यर्थः ॥ एवं च प्रकृतिपरिणामविशेषरूपजातेः स्वत एव लिङ्गयोग इति तात्पर्यम् ॥

(आक्षेपभाष्यम्)

यद्युभयं सर्वत्र, कुतो व्यवस्था ? ।

(समाधानभाष्यम्)

'विवक्षातः ।' संस्त्यानविवक्षायां स्त्री, प्रसवविवक्षायां पुमान्, उभयोरप्यविवक्षायां नपुंसकम् ॥

(आक्षेपभाष्यम्)

तत्र * लिङ्गवचनसिद्धिर्गुणविवक्षानित्यत्वात् * इति लिङ्गपरिहार उपपन्नः, ॥

वचनपरिहारस्तु नोपपद्यते ॥

(समाधानभाष्यम्)

वचनपरिहारश्चाप्युपपन्नः । इदं तावदयं प्रष्टव्यः—अथ यस्य द्रव्यं पदार्थः कथं तस्य एकवचनद्विवचनबहुवचनानि भवन्तीति । एवं स वक्ष्यति एकस्मिन्नेकवचनं द्वयोर्द्विवचनं बहुषु बहुवचनमिति । यदि तस्यापि वाचनिकानि, न स्वाभाविकानि । अहमप्येवं वक्ष्यामि एकस्मिन्नेकवचनं द्वयोर्द्विवचनं बहुषु बहुवचनमिति । नह्याकृतिपदार्थकस्य द्रव्यं न पदार्थः, द्रव्यपदार्थकस्य वा

आकृतिर्न पदार्थः । उभयोरुभयं पदार्थः । कस्यचित्किंचित्प्रधानभूतं किंचिद् गुणभूतम् । आकृतिपदार्थकस्य आकृतिः प्रधानभूता, द्रव्यं गुणभूतम् । द्रव्यपदार्थकस्य द्रव्यं प्रधानभूतमाकृतिर्गुणभूता ॥

(प्रदीपः) वाचनिकानीति । संकीर्णप्रयोगोपलम्भात् असंकरार्थो यथा द्रव्यपदार्थकस्य वाचनिको वचननियमः तथाकृतिवादिनोपि । स ह्येवं व्याचष्टे एकाश्रयसंबन्धविवक्षायामाकृतेरेकवचनं यथा पशुना यजेतेति । अनेकाश्रयसंबन्धविवक्षायां द्विवचनबहुवचने ॥ ननु द्रव्यस्यानभिधेयत्वात्कथं तत्कृत आकृतेर्वचनोपकार इत्याह—नहीति । तत्र यथा पचति पचतः पचन्तीति क्रियाप्राधान्येपि साधनसंख्याकृतो वचनभेदः एवमाकृतिप्राधान्येपि द्रव्यसंख्याकृत इत्यदोषः ॥

(उद्द्योतः) भाष्ये—कथं तस्येति । असंकरेणेति शेषः ॥ ननु शब्दनित्यतायां वाचनिकानीत्ययुक्तमत आह—संकीर्णेति । गोदौ पधान्ना इत्यादावेकत्रापि द्विवचनादिदर्शनेन सांकर्यमिति भावः ॥ व्याचष्ट इति । ह्येकयोरित्यादिसूत्राणीति भावः ॥ अभिधेयत्वेप्युपसर्जनत्वात्कथं तत्कृत उपकारोत आह—तत्र यथेति॥ भाष्ये—द्रव्यं गुणभूतमिति । अस्योपपत्तिरुक्ता जात्याख्यायामितिसूत्रे ॥ साधनसंख्याकृत इति । साधनसंख्यारोपकृत इत्यर्थः ॥ इत्यदोष इति । एवं च लिङ्गयोगः स्वत एव । संख्यायोगस्त्वारोपेण । एका आकृतिरिति प्रतिज्ञा नारोपितसंख्याभिप्राया, नाप्येकशेषारम्भः । अनेकशब्दप्रयोगे मानाभावादिति तात्पर्यम् ॥ अत्र भाष्ये द्रव्यपदार्थवादे आकृतेर्विशेषणत्वोक्त्या तज्जात्यनुगतीकृतानेकव्यक्तिबोधस्यैकस्मादेव शब्दात्सम्भवेन नानाशब्दप्रयोगाप्राप्त्या तत्पक्षेप्येकशेषो न कार्य इति सूचितम् ॥ जातिवादे व्यक्तिर्द्रव्यवादे जातिः शक्यतावच्छेदिकेति च सूचितम् ॥

(७८१ आकृतिवादिवार्तिकम् ॥ ६० ॥)

॥ * ॥ गुणवचनवद्वा ॥ * ॥

(भाष्यम्) गुणवचनवद्वा लिङ्गवचनानि भविष्यन्ति । तद्यथा—गुणवचनानां शब्दानामाश्रयतो लिङ्गवचनानि भवन्ति—शुक्लं वस्त्रम्, शुक्ला शाटी, शुक्लः कम्बलः, शुक्लौ कम्बलौ, शुक्लाः कम्बला इति । यदसौ द्रव्यं श्रितो भवति गुणस्तस्य यल्लिङ्गं वचनं च तद्गुणस्यापि भवति । एवमिहापि यदसौ द्रव्यं श्रिता आकृतिस्तस्य यल्लिङ्गं वचनं च तदाकृतेरपि भविष्यति ॥

(प्रदीपः) यदसाविति । जातितद्वतोरभेदाध्यवसायाद् द्रव्यात्मा जातिः प्रतीयमाना तद्गतलिङ्गसंख्याग्राहिणीत्यर्थः ॥

(उद्द्योतः) ननु गुणवचनानामित्यादिवचनात्तत्रास्तु तथा, इह तु अजातिरिति निषेधात्कथं तत्प्रवृत्तिरत आह—जातितद्वतोरिति । न त्वत्र तद्वचनप्राप्तिः । अत एव गुणवचनवदिति भाष्य उक्तमिति भावः ॥ यद्यपि जातेराश्रयतो न लिङ्गादीति विशेषणानां चेत्यत्रोक्तम्, तथापि विशेष्यगतलिङ्गादिनिषेधः सः । तत्राश्रयपदेन विशेष्यग्रहणात् । इह त्वाश्रयपदेनाधारो गृह्यत इति न विरोध इति भावः ॥ अत्र चाभेद एव बीजं यो यदभेदमापन्नः स स्वाभिन्नाश्रयगतलिङ्गवचनादिग्राहीति नियमात् । इयांस्तु विशेषः शुक्लादिशब्दवाच्यगुणानां गुणिना भेदाभेदविवक्षे शब्दवाच्यजातेस्त्वभेदविवक्षैवेति ॥ परे तु तयोरभेदमादाय ग्रन्थयोजने तदभेदादेवारम्भणादीन्यपि तत्र भविष्यन्तीत्यधिकरणगतिरित्युत्तरग्रन्थानुत्थानमतो गुणवचनानां विशेष्यगतलिङ्गादिग्राहित्ववज्जातेराश्रयगतलिङ्गादिग्राहित्वं स्वभावादित्येतद्भाष्यार्थमाहुः ॥

(७८२ आकृतिवादिवार्तिकम् ॥ ६१ ॥)

॥ * ॥ अधिकरणगतिः साहचर्यात् ॥ * ॥

(भाष्यम्) आकृतावारम्भणादीनां संभवो नास्तीति कृत्वा आकृतिसहचरिते द्रव्ये आरम्भणादीनि भविष्यन्ति ॥

(प्रदीपः) *चोदनासु च तस्यारम्भात्* इति यदुक्तं तत्परिहारार्थमाह—अधिकरणगतिरिति । यथाग्निरानीयतामित्युक्ते केवलस्याग्नेरानयनासंभवान्नान्तरीयकत्वादचोदितमपि पात्रमानीयते एतदेवाग्नेरानयनं यत् पात्रस्थस्य, तथा आकृतावारम्भणादीनि चोद्यमानानि सामर्थ्यात् साहचर्याद् द्रव्यमभिनिविशन्ते । सर्व एवाकृतेः क्रियायोगोऽन्तर्भावितद्रव्याया एवेति द्रव्यद्वारकः संपद्यते ॥

(उद्द्योतः) भाष्ये—आकृताविति । प्रधानभूतामित्यादि । आकृतिरेव तज्जन्यबोधे प्रधानम्, क्रिया तु पात्रे इव द्रव्य

इति भावः । शाब्दबोधे तु न बाधज्ञानं प्रतिबन्धकमिति न तदनुपपत्तिः ॥ **सर्वएवेति** । गौरानीयतामित्यादिरपीत्यर्थः ॥ भाष्ये—**आरम्भणं** क्रयः । **आलम्भनं** स्पर्शः ॥ **आकृतिसहचरिते इति** । आकृत्याश्रये इत्यर्थः ॥

(७८३ आकृतिवादिवार्तिकम् ॥ ६२ ॥)

॥ * ॥ न चैकमनेकाधिकरणस्थं युगपदित्यादित्यवद्विषयः ॥ * ॥

(भाष्यम्) **न खल्वप्येकमनेकाधिकरणस्थं युगपदुपलभ्यत इत्यादित्यवद्विषयो भविष्यति। तद्यथा । एक आदित्योनेकाधिकरणस्थो युगपदुपलभ्यते ॥**

(आक्षेपभाष्यम्)

विषम उपन्यासः । नैको द्रष्टाऽनेकाधिकरणस्थमादित्यं युगपदुपलभते ॥

(समाधानभाष्यम्)

एवं तर्हि—

(७८४ आकृतिवादिवार्तिकम् ॥ ६३ ॥)

॥ * ॥ इतीन्द्रवद्विषयः ॥ * ॥

(भाष्यम्) **तद्यथैक इन्द्रोनेकस्मिन्क्रतुशत आहूतो युगपत्सर्वत्र भवत्येवमाकृतिर्युगपत्सर्वत्र भवेदिति॥**

(उद्योतः) **इतीन्द्रवदिति** । स्वभावाद्धेतुरहितदृष्टान्तेनाप्यनेकवृत्तित्वं जातेरभ्युपगम्यत इत्यर्थः ॥

(७८५ आकृतिवादिवार्तिकम् ॥ ६२ ॥)

॥ * ॥ अविनाशोनाश्रितत्वात् ॥ * ॥

(भाष्यम्) **द्रव्यविनाशे आकृतेरविनाशः ॥ कुतः ? । अनाश्रितत्वात् । अनाश्रिता आकृतिर्द्रव्यम् ॥**

(प्रदीपः) **अनाश्रितत्वादिति** । यथा गुणानां द्रव्याधीनस्थितित्वादाश्रितत्वम्, नैवमाकृतेः ? अन्यत्रापि प्रत्ययाभिधानयोराकृतिनिमित्तयोर्भावान्नित्यत्वं तस्या इत्यर्थः ॥

(उद्योतः) नन्वनेकव्यक्तिवृत्तीति सामान्यलक्षणविरुद्धमेतदत आह—**यथेति** । द्रव्याधीनस्थितिकत्वमाश्रितत्वं विवक्षितमित्यर्थः ॥ **अन्यथापीति** । कर्णशष्कुल्यनधीनस्थितिकस्याप्याकाशस्य तदवच्छिन्नतया श्रोत्ररूपत्ववद् द्रव्यमनाश्रितस्यापि महासामान्यस्य नित्यस्य गवादिद्रव्यपरिच्छिन्नतया गोत्वादिरूपतेत्यर्थः ॥ **अन्यत्रापीति** क्वचित्पाठः ॥ तत्र व्यक्त्यन्तर इत्यर्थः ॥ **प्रत्ययो,** ज्ञानम् । **अभिधानं,** शब्दः ॥

(आक्षेपभाष्यम्)

किमुच्यते अनाश्रितत्वादिति, यदिदानीमेवोक्तम्—*अधिकरणगतिः साहचर्यादिति ? ॥

(प्रदीपः) इतरः संबन्धमात्रमाश्रितत्वं मत्वा पृच्छति—**किमुच्यत इति** ॥

(समाधानभाष्यम्)

एवं तर्हि—

(७८६ न्यासान्तरवार्तिकम् ॥ ६२ ॥)

॥ * ॥ अविनाशोऽनैकात्म्यात्* ॥ * ॥

(भाष्यम्) **द्रव्यविनाशे आकृतेरविनाशः । कुतः ? । अनैकात्म्यात् । अनेक आत्मा आकृतेर्द्रव्यस्य च । तद्यथा—वृक्षस्थोऽवतानो वृक्षे छिन्नेपि न विनश्यति ॥**

---

* आकृतिवादिसंदर्भमिममनुसृत्य भट्टपादैरप्युक्तम्—

"आनन्त्यव्यभिचाराभ्यां शक्त्यनेकत्वदोषतः ।
संदेहाद्वरमज्ञानाच्चित्रबुद्धेरभावतः ॥
अन्वयव्यतिरेकाभ्यामेकरूपप्रतीतितः ।
आकृतेः प्रथमज्ञानात्तस्या एवाभिधेयता ॥
व्यक्त्याकृत्योरभेदाच्च व्यवहारोपयोगिता ।
लिङ्गसंख्यादिसंबन्धाः सामानाधिकरण्यधीः ॥
सर्वं समञ्जसं ह्येतद्वस्त्वनेकान्तवादिनः ।
लक्षणा वाभ्युपेतव्या जातेस्तेनाभिधेयता ॥"

इति ॥ व्याख्यातं चैतच्छास्त्रदीपिकायाम्—'नह्यनन्तासु व्यक्तिषु संज्ञित्वं शक्यतेऽवगन्तुम् । व्यभिचाराच्च व्यक्तीनामशब्दार्थत्वम् नियमलक्षणत्वात्संबन्धस्यानियमे तदयोगात् । अनन्ताश्च शब्दव्यक्त्योऽनन्तासु व्यक्तिषु कल्प्याः । जात्युपलक्षणत्वेऽप्यभिधेयानामनन्तत्वाच्छक्त्यानन्त्यमस्त्येव । व्युत्पत्तिकाले हि जातिरुपलक्षणम्, नत्वभिधानसमये । अभिधानं हि प्रातिस्विकेनैव रूपेण व्यक्तीनाम् । तद्यथा—अक्षत्रयमेकास्वरकस्थमेकापवरकास्थित्वेनोपलक्ष्य कश्चित् कंचिदाह—'य एतस्मिन्नपवरकेऽधुना आसते ते त्रयोऽक्षशब्दाभिधेयाः' इति । तत्र यद्यपि व्युत्पत्तिसमयेऽपवरकस्थितिर्नियोगेनोपलक्षणं लभ्यते तथापि शब्दस्तदनादरेण व्यक्तित्रयमेव स्वरूपेणाभिधत्ते इति भवति शक्तित्रयम् । एवमिहापि यद्यपि व्युत्पत्तिसमये जातिरेकोपलक्षणमासीत्तथापि शब्दस्तामस्पृशन्नेव नानारूपा व्यक्तीः स्वेन रूपेणाभिधत्ते इति स्यादेव शक्त्यानन्त्यम् । अपिच यद्यपदेश्यं धर्मिरूपमभिधेयं ततो गोशब्दोच्चारणका व्यक्तिः प्रतीयमानाऽपि नाश्वादिव्यक्तिभ्यो व्यवच्छिन्ना प्रतीता स्यात् । नह्यसाधारणमाकारमन्तरेण द्रव्यं द्रव्यान्तरव्यवच्छिन्नं प्रतीयते । तत्र गौरित्युक्ते सर्वत्राविशिष्टा प्रतीतिः स्यात् ॥ अथाभिधानसमय एव जातिरुपलक्षणमित्यभिदधदेव हि व्यक्तिं शब्दो जातिमुपलक्षणमादाय तज्जातीयरूपेणाभिधत्ते गोजातीयमिति ततः प्रथमं जातिरभिधातव्या । नह्यनभिधाय जातिं तज्जातीयत्वेन रूपेण व्यक्तिरभिधातुं शक्यते । ततश्च विशिष्टाभिधानमेव वाचोयुक्त्यन्तरेणापन्नं न शुद्धाभिधानम् । विशिष्टाभिधाने च पूर्वतरं विशेषणमभिधातव्यम् । तदभिधाने च तत एवात्यन्ताविनाभूतव्यक्तिप्रतिपत्तिसिद्धेर्न तत्राभिधानशक्तिकल्पनावसरः । किंच गोशब्द उच्चारिते व्यक्तिषु संशयो भवति न कस्यां चिन्निर्णयः । यत्र च संशयो न तस्यामभिधेयता शब्दस्य निश्चायकत्वात् । सामान्यं तु निर्णीयत इति भवत्यभिधेयम् । नन्वसत्यपि व्यक्तिविशेषनिर्णये व्यक्तिमात्रं निर्णीयत एव । किमिदं व्यक्तिमात्रं, सामान्यं, विशेषो वा द्व्याकारैव हि वस्तुषु बुद्धिर्व्यावृत्त्यनुगतरूपा । तत्र विलक्षणबुद्ध्यालम्बनं च व्यक्तिः, समानबुद्ध्यालम्बनं च सामान्यम् । न तदुभयातिरिक्तं व्यक्तिमात्रं नाम किंचिदस्ति वस्तुनो रूपम् । सामान्यमेव त्वनेन मात्रशब्देना-

(प्रदीपः) **अनैकात्म्यादिति** । पूर्वोक्त एवार्थो विशिष्यानेन प्रतिपाद्यते नित्या आकृतिरेका सर्वत्रगा, तद्विपरीतं द्रव्यमिति भेदाद् द्रव्यविनाशेपि न जातेर्विनाशः । गुणानां तु द्रव्याधीनस्थित्युत्पत्तित्वादाश्रयनाशेऽवश्यं नाश इति न तैर्व्यभिचारः ॥ **वृक्षस्थोवतान इति** । यथा वृक्षस्योपरि द्राक्षादिलतावतानः स्थितो न वृक्षविनाशमनु विनश्यति तथा जातिरपीत्यर्थः ॥

(उद्द्योतः) **पूर्वोक्त एवेति** । अनाश्रितत्वादित्येष एवेत्यर्थः ॥ **भेदादिति** । नित्यमेकमनेकव्यक्तिवृत्ति **सामान्यम्**, तद्विपरीतं द्रव्यमिति भेद इत्यर्थः ॥ **अनैकात्म्यादित्यस्य** भिन्नस्वभावत्वादित्यर्थ इति भावः ॥

(७८७ आकृतिवादिवार्तिकम् ॥ ६३ ॥)

॥ * ॥ वैरूप्यविग्रहौ द्रव्यभेदात् ॥ * ॥

(भाष्यम्) **वैरूप्यविग्रहावपि द्रव्यभेदाद्भविष्यतः ॥**

(प्रदीपः) **वैरूप्यविग्रहाविति** । द्रव्याणां स्वगतभेदप्रतिबद्धौ वैरूप्यविग्रहावित्यर्थः । तत्र द्रव्यगतभेदोपचारादेकस्यामप्याकृतौ समुच्चयोपपत्त्या विग्रहो न विरुध्यते ॥

(उद्द्योतः) ननु विग्रहसत्त्वे द्वन्द्वापत्तिरत उक्तं **समुच्चयोपपत्त्येति** । तत्र तु सहविवक्षाभावान्न द्वन्द्व इति भावः ॥ सहविवक्षायां तु न तथा प्रयोगोऽनभिधानादिति बोध्यम् ॥ द्रव्यगतलिङ्गादिग्राहित्ववत्तद्गतभेदग्राहित्वमपि तस्या इति बोध्यम् ॥

(७८८ आकृतिवादिवार्तिकम् ॥ ६४ ॥)

॥ * ॥ व्यर्थेषु च सामान्यात्सिद्धम् ॥ * ॥

(भाष्यम्) **विभिन्नार्थेषु च सामान्यात्सिद्धम् । सर्वत्र अश्नोतेरक्षः, पद्यतेः पादः, मिमीतेः माषः । तत्र क्रियासामान्यात्सिद्धम् ॥**

(प्रदीपः) **क्रियासामान्यादिति** । भिन्नासु क्रियासु अभिन्नप्रत्ययाभिधाननिमित्तं यत्सामान्यं तदेव द्रव्येष्वपि तन्निमित्तं भवति । यथा पाचक इत्याश्रयान्तरगतमपि हि सामान्यं समवेतसमवायाद् द्रव्ये उपकरोति । यथा गैरिकादिगतं लौहित्यं संयुक्तसमवायात् पटे लौहित्यप्रत्ययमादधाति ॥

(उद्द्योतः) **भिन्नास्विति** । आश्रयभेदात्कर्मभेदाच्चेत्यर्थः ॥ **तदेवेति** । समवेतसमवायेनेत्यर्थः ॥ **आश्रयान्तरगतं** पाकक्रियागतम् ॥ **सामान्यं** पाकत्वादि ॥ परम्परयोपकर्तृत्वे दृष्टान्तमाह—**यथेति** । एवं च व्याप्त्यादिगतसामान्यस्य परम्परया द्रव्ये सत्त्वेन तज्जातिविशिष्टस्य द्रव्यस्य वाच्यत्वमिति भावः ॥ न चैवं नानार्थोच्छेदः, नानाजातीनां संबन्धघटकत्वेन नानार्थत्वोपपत्तेः ॥ तत्तत्क्रियारूपसामान्यसमनियतस्याक्षत्वादेर्जातिरूपस्याक्षपदार्थत्रयसाधारणस्यापि शक्यतावच्छेदकत्वशक्यत्वान्यतराङ्गीकारात्सिद्धमिति भाष्यार्थमन्ये ॥ सूत्रारम्भेपीदमावश्यकमेकरूपेणैव सर्वार्थबोधादिति भाव इति बोध्यम् ॥

(व्याख्यान्तरभाष्यम्)

अपरस्त्वाह—पुरा कल्प एतदासीत्षोडश माषाः कार्षापणम्, षोडशपलाश्च माषशंवत्यः । तत्र संख्यासामान्यात्सिद्धम् ॥ सरूपाणाम् ॥ ६४ ॥

(प्रदीपः) **पुरा कल्पइति** । पुरा कल्पे प्रसिद्धोर्थः संप्रति निमित्ताभावेपि तथैव व्यपदिश्यते ॥ **माषशंवत्य इति** । तत्र षोडशभागत्वेन माषः प्रसिद्धः तथैव कार्षापणे माषः [षोडशभाग इति] षोडश[भाग]त्वं नाम सामान्यमुपादत्ते माषशब्द इति सिद्धमेकशब्दत्वम् ॥ **संख्यासामान्यादिति** । संख्यैव सामान्यमभिन्नप्रत्ययहेतुत्वात् ॥ ननु षोडशसंख्या षोडशसु पदार्थेषु व्यासज्य स्थिता न त्वेकस्मिन् षोडशे । एवं तर्हि षोडशसंख्यापूरणत्वं नाम यत्सामान्यं तत्संख्यामूलत्वात्संख्यासामान्यमुच्यत इत्यदोषः ॥ अथ डित्था इति भिन्नेषु संज्ञिष्वेकाकृत्ययोगात् कथमेकशब्दवाच्यत्वम् ॥ उच्यते । भिन्नडित्थशब्दगतं डित्थशब्दत्वं नाम यथा शब्देष्वभिन्नप्रत्ययाभिधानहेतुः तथा सोयमिति शब्दार्थयोरभेदाध्यवसायादध्यस्तडित्थशब्देषु संज्ञिष्वपि सबन्धिसंबन्धादभिन्नप्रत्ययाभिधाननिमित्तमिति सिद्धमेकशब्दवाच्यत्वम् ॥ तथा तावित्येताविति च परोक्षत्वप्रत्यक्षत्वादिकं सामान्यमाश्रयणीयम् । गोत्वाश्वत्वे सामान्ये इति व्यावृत्तेष्वनुवृत्तप्रत्ययहेतुसामान्यानामपि सामान्यमाश्रयितव्यम् । अथ वा **निःसामान्यानि सामान्यानीति** तार्किकदर्शनं न वैयाकरणैर्नियोगत आस्थेयम् । कार्योन्नीयमाना हि तेषां पदार्था इति सामान्येष्वपि सामान्यमस्ति । अभावाश्चत्वार इत्यत्रापि निरुपाख्यत्वं सामान्यं कल्पनीयम् । तदेवं सर्वत्राकृतिसद्भावात्सिद्धमेकशब्दत्वम् ॥ ६४ ॥

भिधीयते इति तदेवाभिधेयम् । प्रथमं च सामान्यमेव शब्दाद्गम्यते पश्चाच्च व्यक्त्याकाङ्क्षामात्रं जायते । ततस्तदेवाभिधेयं न व्यक्तिविशेषः । विचित्राश्च खण्डमुण्डादिरूपा व्यक्तय इति विचित्रा गोशब्दोच्चारणे बुद्धिः स्यात् । एकाकारा तूत्पद्यते । अतोऽभिधेया जातिः । अन्वयव्यतिरेकाभ्यां चैवमेव युक्तम् ॥ व्यवहाराङ्गता च जातेर्व्यक्त्यनतिरेकादुपपद्यते । अतोऽभिधेया जातिः । नहि जातिर्नाम व्यक्तेरर्थान्तरभूतं किमपि तत्त्वम् । अपि तु वस्त्वेव भेदाभेदोभयात्मकं व्यावृत्त्यनुगतरूपतया बुद्ध्यते ॥ तत्र सामान्यं शब्दार्थ इति । अयमर्थः—सामान्यात्मना वस्तु शब्दाद्गम्यते, न विशेषात्मनेति । यच्च सामान्यात्मना शब्देन बोधितं तस्य क्रियासंबन्धश्चोद्यते । शक्नोति च तत्क्रियां साधयितुम् । अतस्तदेव क्रियाश्रयविशेषरूपमपि । लिङ्गसंख्याकारकसंबन्धसामानाधिकरण्यं च सर्वमनेकान्ताश्रयेणैव सुपरिहारम् । यदा तु भेद एव जातिव्यक्त्योस्तदा सर्वमिदं लाक्षणिकव्यवस्थाश्रयणेनोपपद्यते । यत्र तु 'पशुना यजेत' 'अरुणया क्रीणाति' इत्येवमादौ करणत्वश्रवणं तत्र जातिगुणयोरेवामूर्तयोरपि द्रव्यपरिच्छेदेन मुख्यमेव करणत्वमुपपन्नम् ॥ अधिकरणसंभवनादिरूपत्वं चामूर्तस्यासंभवादभेदं लक्षणां वाश्रित्य समर्थनीयम् ॥ आह च—

"तेन तत्रवितस्यक्तेः क्रियासंबन्धचोदना ।
जातिव्यक्त्योरभेदो वा वाक्यार्थेषु व्यवस्थितः ॥"

इति ॥ "तस्मात्सामान्यमेवाभिधेयम् न व्यक्तिरिति सिद्धम्" इत्याकृत्यधिकरणे पार्थसारथिमिश्रैः ॥

(उद्योतः) नन्विदानीन्तनमाषस्य षोडशभागत्वाभावात्कथं संख्यासामान्यमत आह—पुरेति ॥ व्यपदिश्यते इति । आरोपादिति भावः । माषशब्दवाच्यां माषः षोडशभागपलरूपः । कार्षापणे माषः पञ्चगुञ्जामितः षोडशो भागस्तयोः षोडशभागत्वेन सामान्येन सर्वेषु माषत्वव्यवहारः । इदानीं त्वष्टगुञ्जमितमाषे षोडशत्वमारोप्य तथा प्रयोग इति भावः ॥ ननु संख्यागतं सामान्यं संख्याशब्दप्रवृत्तावेव कारणमत आह—संख्यैवेति । तत्संख्येति । संख्यामूलकत्वादित्यर्थः ॥ अभिन्नप्रत्यय एकाकारप्रत्ययः ॥ अभिधानम् । शब्दप्रयोगः ॥ परोक्षत्वेति । इदं बुद्धिविषयतावच्छेदकावच्छिन्नत्वादीनामुपलक्षणम् ॥ तार्किकाः । वैशेषिकादयः ॥ निरुपाख्यत्वं, विशिष्य निर्वक्तुमशक्यत्वम् । तत्समनियतो जातिविशेषोऽभावत्वमेव सर्वत्रेत्यन्ये ॥ ६४ ॥

(११३ एकशेषसूत्रम् । १ । २ । ३ आ. २ सू.)

वृद्धो यूना तल्लक्षणश्चेदेव विशेषः १।२।६५ ॥

(अनिष्टापत्तिवारणाधिकरणम्)

(आक्षेपभाष्यम्)

इह कस्मान्न भवति—अजश्च बर्करश्च, अश्वश्च किशोरश्च, उष्ट्रश्च करभश्चेति ? ॥

(प्रदीपः) वृद्धो ॥ ६५ ॥ इह कस्मादिति । उभयगतिरिह शास्त्रे सम्भवतीति मत्वा प्रश्नः ॥ अथ वा वृद्धशब्द इह शास्त्रे अपत्यविशेषे न परिभाषित इति स तावद्वयोवाची गृह्यते । तत्साहचर्याच्च युवशब्दोपि तथैवेति प्रश्नः ॥ अजोष्ट्राश्वशब्दानां जातिशब्दत्वेप्यत्र शब्दान्तरसन्निधानाद् वृद्धावस्थाभिधायित्वं द्रष्टव्यम् । अन्यथा सामान्यविशेषशब्दानां द्वन्द्वो न स्यात् । सामान्यशब्देन सर्वविशेषाणामाक्षेपाद् विशेषैः सह समुच्चयाभावात् ।

(उद्योतः) वृद्धोयूना ॥ ६५ ॥ अजबर्करादीनां वृद्धयुवसंज्ञकत्वाभावादाह—उभयेति ॥ अथवेति । स्वशास्त्रीयवृद्धसंज्ञकं तु न गृह्यते व्याख्यानादिति बोध्यम् ॥ सामान्यविशेषवाचिनां सहविवक्षाभावाद् द्वन्द्वाभावेन तदपवादैकशेषस्याप्यप्राप्तेराह—अजोष्ट्रेति । यद्यपि करभकिशोरशब्दौ शावकवचनौ तथापि भाष्यप्रामाण्यात्तरुणवचनौ बोध्यौ । बर्करस्तरुणोऽजः ॥ समुच्चयाभावादिति । सहविवक्षाभावादित्यर्थः ॥

(समाधानभाष्यम्)

तल्लक्षणश्चेदेव विशेष इत्युच्यते । न चात्र तल्लक्षण एव विशेषः ॥

(प्रदीपः) वक्ष्यमाणं मनसि कृत्वाह—तल्लक्षणश्चेदिति ।

(उद्योतः) वक्ष्यमाणम्—'यत्रोर्ध्वं प्रकृतेरित्यादि ॥

(समाधानबाधकभाष्यम्)

तल्लक्षण एव विशेषो यत्समानायामाकृतौ शब्दभेदः ॥ वृद्धो यूना ॥ ६५ ॥

(प्रदीपः) इतरोऽगृहीताभिप्राय आह—तल्लक्षण इति ॥ परिहारस्तु उत्तरत्र वक्ष्यते ॥ ६५ ॥

(उद्योतः) उत्तरत्र—भ्रातृपुत्राविलत्र ॥ ६५ ॥

(११४ एकशेषसूत्रम् ॥ १ । २ । ३ । आ. ३ सू.)

स्त्री पुंवच्च ॥ १।२।६६ ॥

(स्त्रीशब्दार्थनिर्णयाधिकरणम्)

(आक्षेपभाष्यम्)

इदं सर्वेष्वेव स्त्रीग्रहणेषु विचार्यते—स्त्रीग्रहणेषु स्त्रीप्रत्ययग्रहणं वा स्यात्, स्त्र्यर्थग्रहणं वा, स्त्रीशब्दग्रहणं वेति ॥

किं चातः ? ॥

यदि प्रत्ययग्रहणं वा शब्दग्रहणं वा, 'गार्गी च गार्ग्यायणौ च गर्गाः' केन यशब्दो न श्रूयते "अस्त्रियाम्' इति हि लुगुच्यते । इह च गार्गी च गार्ग्यायणौ च गर्गान्पश्य "तस्माच्छसो नः पुंसि' इति नत्वं न प्राप्नोति ॥ अथार्थग्रहणम्, न दोषो भवति ॥

(प्रदीपः) स्त्री पुंवच्च ॥६६॥ इदमिति । यदि स्त्रीशब्दस्य स्वरितत्वं प्रतिज्ञायते—तदा स्त्र्यधिकारविहितटाबादिप्रत्ययग्रहणम् । ततश्चायमर्थः । पुंवत् स्त्रीप्रत्ययो न भवतीत्यभावातिदेशः क्रियते । स्वरितत्वाभावे तु शब्दग्रहणमर्थग्रहणं वा । तत्र शब्दग्रहणपक्षे स्त्रीशब्दस्य पुंशब्दस्येव रूपं भवतीति स्त्रीत्वमनिवृत्तमेव ॥ अर्थग्रहणपक्षे तु पुमर्थातिदेशे तदर्थप्रतिबद्धानां कार्याणां सिद्धिः । तत्रार्थस्य प्राधान्याददुष्टत्वाच्चार्थपक्ष एवाश्रीयते ॥ अस्त्रियामितीति । यदायं प्रसज्यप्रतिषेधः तदा दोषः । पर्युदासे तु शिष्यमाणः शब्दो निवर्त्यमानार्थाभिधायीत्यस्ति स्त्रीसदृशोर्थ इति लुक् सिध्यति ॥ गर्गान्पश्येति । स्त्रीत्वस्यानिवृत्तत्वात् नायं पुंबहुत्वे शस् उत्पन्न इति नत्वं न सिध्यति ॥ ६६ ॥

(उद्योतः) स्त्रीपुंवच्च ॥ ६६ ॥ टाबादीति । क्तिनादीनां तु न ग्रहणं वृद्धो यूनेत्यधिकारात् । अत्र पक्षे पुंवदिति सामर्थ्याद्भावातिदेशः ॥ शब्देति । स्त्र्यर्थवृत्तिशब्देत्यर्थः ॥ वृद्धेतिविशेषणसामर्थ्यात्स्वरूपग्रहणं नेति भावः ॥ दोषइति । यज्ञञोश्चेत्यत्राऽस्त्रियामित्यनुवृत्तेः ॥ पर्युदासेस्विति । सर्वं वाक्यं सावधारणमिति न्यायेनास्त्रियामेव वर्तमानस्येत्यर्थात् पर्युदासेपि दोष इत्यन्ये ॥ पुंबहुत्वे इति । पुंमात्रगतबहुत्वे इत्यर्थः ॥ ६६ ॥

(समाधानभाष्यम्)

यथा न दोषस्तथास्तु ॥

(अनिष्टवारणाधिकरणम्)

(आक्षेपभाष्यम्)

इह कस्मान्न भवति—अजा च बर्करश्च, वडवा च किशोरश्च, उष्ट्री च करभश्चेति ? ।

(समाधानभाष्यम्)

तल्लक्षणश्चेदेव विशेष इत्युच्यते । न चात्र तल्लक्षण एव विशेषः ।

(समाधानबाधकभाष्यम्)

तल्लक्षण एव विशेषो यत्समानायामाकृतौ शब्दभेदः ॥ स्त्री पुंवच्च ॥ ६६ ॥

(११५ एकशेषसूत्रम् ॥ १ । २ । ३ आ. ५ सू.)

पुमान् स्त्रिया ॥ १।२।६७ ॥

(अनिष्टवारणाधिकरणम्)

(आक्षेपभाष्यम्)

इह कस्मान्न भवति हंसश्च वरटा च, कच्छपश्च डुलिश्च, ऋश्यश्च रोहिच्चेति ? ॥

(समाधानभाष्यम्)

तल्लक्षणश्चेदेव विशेष इत्युच्यते । न चात्र तल्लक्षण एव विशेषः ॥

(समाधानबाधकभाष्यम्)

तल्लक्षण एव विशेषो यत्समानायामाकृतौ शब्दभेदः ॥ पुमान् स्त्रिया ॥ ६७ ॥

(११६ एकशेषसूत्रम् ॥ १ ।२।३ आ० ५ सू०)

भ्रातृपुत्रौ स्वसृदुहितृभ्याम् ॥ १।२।६८ ॥

(आक्षेपभाष्यम्)

किमर्थमिदमुच्यते, न "पुमान् स्त्रिया" इत्येव सिद्धम् ॥

(समाधानभाष्यम्)

न सिध्यति । तल्लक्षणश्चेदेव विशेष इत्युच्यते, न चात्र तल्लक्षण एव विशेषः ।

(समाधानबाधकभाष्यम्)

तल्लक्षण एव विशेषो यत्समानायामाकृतौ शब्दभेदः ॥

(प्रदीपः) भ्रातृ ॥ ६८ ॥ यत्समानायामिति । एकापत्यत्वं नाम समानाकृतिरस्ति ॥

(समाधानसाधकभाष्यम्)

एवं तर्हि सिद्धे सति यदिमं योगं शास्ति तज्ज्ञापयत्याचार्यः—'यत्रोर्ध्वं प्रकृतेः स्यात्तल्लक्षण एव विशेषः, तत्रैकशेषो भवति' ॥

किमेतस्य ज्ञापने प्रयोजनम् ? ॥

हंसश्च वरटा च, कच्छपश्च डुलिश्च, ऋश्यश्च रोहिच्चेति । अत्रैकशेषो न भवति ॥ पूर्वयोर्योगयोर्भूयान्परिहारः—यावद् ब्रूयाद् गोत्रं यूनेति तावद् वृद्धो यूनेति ॥ पूर्वसूत्रे गोत्रस्य वृद्धमिति संज्ञा क्रियते ॥

(प्रदीपः) ऊर्ध्वमिति । यत्रैका प्रत्ययप्रकृतिरन्यत्तु वैरूप्यं तत्रैकशेष इत्यर्थः ॥ त्यदादीनि सर्वैर्नित्यमित्येतद्वर्जयित्वा सर्वत्र सरूपाणामित्यस्यानुवृत्त्याश्रयणाद् यथोक्तार्थलाभः । अत्रैवार्थे एतत्सूत्रं लिङ्गम् । पदान्तरगम्येपि तल्लक्षणविशेषे पुमान् स्त्रियेत्येकशेषो भवति यथा गौश्चायं गौश्चेयमित्येतौ गावौ चरत इति ॥ वरटाचेति । वरटा हंसी ॥ पूर्वसूत्र इति । पूर्वाचार्यकृते व्याकरणे अपत्यमन्तर्हितं वृद्धमिति पौत्रप्रभृतेरपत्यस्य वृद्धसंज्ञा कृता । वृद्धो यूनेत्यत्र वै कृत्रिमस्य जीवति तु वंश्ये युवेत्यस्य ग्रहणं तत्साहचर्याद्वृद्धस्याप्यपत्यस्य ग्रहणमित्यर्थः ॥

(उद्योतः) भ्रातृपुत्रौ ॥ ६८ ॥ यत्रैकेति । समानेत्यर्थः ॥ अन्यत्त्विति । अन्यकृतमित्यर्थः ॥ वैरूप्यमिति । (वा) स्वार्थे ष्यञ् ॥ इत्येतद्वर्जयित्वेति । भ्रातृपुत्रौ पिता मात्रा श्वशुरः श्वश्र्वा इत्येतेषां ज्ञापकत्वान्नपुंसकमनपुंसकेनेत्यत्र तदनुवृत्तेश्च त्यदादीनीत्यस्यैव वर्जनमुक्तं, तत्र हि सर्वग्रहणसामर्थ्यान्न तन्निवृत्तिरिति भावः ॥ ननु स्त्रीगोव्यक्तिपुंगोव्यक्तिवाचकयोर्गौश्च गौश्चेत्येकशेषानापत्तिस्तल्लक्षणविशेषाभावादत आह—पदान्तरगम्येपीति ॥ तल्लक्षणविशेषे इति । स्त्रीत्वपुंस्त्वरूपविशेषे इत्यर्थः ॥ एतौ गावाविति । तल्लक्षण इत्यस्य तद्रूप इत्येवार्थः ॥ ऊर्ध्वमित्यादेश्च प्रकृत्यतिरिक्तशब्दकृत एव चेत्तद्रूपो विशेष इत्यर्थः । सूत्रेप्येवेत्यस्य प्रकृत्यतिरिक्तकृत इत्यादिः । प्रकृत्यतिरिक्तकृत एव तद्रूपो विशेषश्चेदित्यन्वयः ॥ तद्रूप इत्यस्य वृद्धत्वयुवत्वरूपः स्त्रीत्वपुंस्त्वरूप इत्यर्थः । प्रकृतिश्चात्र स्त्रीत्वा-

घर्थकप्रत्ययस्य गृह्यते इति बोध्यम् ॥ न चेन्द्रेन्द्राण्यावित्यादावप्यस्य प्रवृत्तिः प्राप्नोति । आनुकः प्रकृत्यवयवत्वेन तत्कृताप्यत्र स्त्रीत्वप्रतीतिरिति न दोषः ॥ एवं हि यत्रोर्ध्वमिति भाष्ये एवोऽस्थाने भवत्यक्षरस्वारस्यं च नेति ऊर्ध्वं प्रकृतेर्विशेषश्चेत्तल्लक्षण एवेत्यन्वयेन तद्भिन्तरकृतविशेषविरहरूपे विशिष्टाभावे तात्पर्यान्न दोषः । स चेह विशेष्याभावादस्त्येवेत्यन्ये ॥

(प्रत्याख्यानाधिकरणम्)

(७८९ प्रत्याख्यानवार्तिकम् ॥ १ ॥)

॥ * ॥ असरूपाणां युवस्थविरस्त्रीपुंसानां विशेषस्याविवक्षितत्वात् सामान्यस्य च विवक्षितत्वात्सिद्धम् ॥ * ॥

(भाष्यम्) असरूपाणां युवस्थविरस्त्रीपुंसानां विशेषश्चाविवक्षितः सामान्यं च विवक्षितम् । विशेषस्याविवक्षितत्वात्सामान्यस्य च विवक्षितत्वात्सरूपाणामेकशेष एकविभक्तावित्येव सिद्धम् ॥

(प्रदीपः) असरूपाणामिति । गर्गापत्यत्वं सामान्यं वृद्धयूनोर्विवक्षितमिति सिद्धमेकशब्दत्वम् । आरभ्यमाणेप्येकशेषे गार्ग्याविति विशेषो नावधार्यते—'किं वृद्धयुवानौ प्रक्रान्तौ, उत वृद्धा'विति । प्रकरणाद्यपेक्षे तु विशेषावसाये सामान्योपक्रमेपि तथैव विशेषोवसायिष्यत इति नार्थ एकशेषारम्भेण । द्वन्द्वोपि गार्ग्यगार्ग्यायणावित्यनभिधानान्न भविष्यति । स्त्रीपुंसयोरपि मृगक्षीरवज्जातिमात्रविवक्षायां ब्राह्मणावित्यादिप्रयोगसिद्धिः ॥

(उद्द्योतः) भाष्ये असरूपाणामित्यनेनोक्तत्रिसूत्रीं प्रत्याचष्टे—गर्गापत्यत्वमिति । गोत्रयुवसाधारणमपत्यत्वेनैव गोत्रादिप्रत्ययेभ्यो बोधाद् युवत्वादिविशेषानादरेण गार्ग्यश्च गार्ग्यश्चेति गोत्रशब्दयोरेव सरूपैकशेषेण सिद्धमित्यर्थः ॥ नन्वेवमन्यतरस्य युवत्वं न प्रतीयेतेत्यत आह—आरभ्यमाणेपीति ॥ नार्थ इति । वृद्धोयूनेत्यादिनेत्यर्थः ॥ ननु प्रकरणाद्यनपेक्ष्य युवत्वादिप्रतिपादनेच्छायां द्वन्द्वः स्यादत आह—द्वन्द्वोपीति । सहविवक्षायां द्वयोः प्रयोगाभाव एवानभिधानादिति भावः ॥ ननु स्त्र्यभिधाननिमित्तप्रत्ययनिवृत्तये पुमान् स्त्रियेत्यावश्यकमत आह—स्त्रीति ॥

(अनिष्टवारणाधिकरणम्)

(आक्षेपभाष्यम्)

"पुमान् स्त्रिया" इह कस्मान्न भवति—ब्राह्मणवत्सा च ब्राह्मणीवत्सश्चेति ? ॥

(प्रदीपः) ब्राह्मणवत्सा चेति । अस्त्यत्र प्रकृतेरूर्ध्वं तल्लक्षणो विशेषः, न चात्र कश्चिद्विशेषः स्त्रीपुंसयोरुपात्तः ॥

(उद्द्योतः) इदानीं पुमान् स्त्रियेत्यस्य सार्थक्यं शङ्कते—भाष्ये पुमान् स्त्रियेहेति । उक्तरीत्याऽनेकशेषस्य साधयितुमशक्यत्वादेतदर्थमेव तत्सूत्रं कस्मान्न भवतीति प्रश्नः ॥ कृतेपि सूत्रेऽत्र न प्राप्नोतीत्युत्तरम् । तत्र प्रश्नमुपपादयति—अस्त्यत्र प्रकृतेरिति । ब्राह्मणरूपाया वत्सरूपायाश्चेत्यर्थः ॥ विशेषः । प्रधानत्वरूपः ॥

(७९० समाधानवार्तिकम् ॥ २ ॥)

॥ * ॥ ब्राह्मणवत्साब्राह्मणीवत्सयोर्लिङ्गस्याविभक्तिपरस्य विशेषवाचकत्वादनेकशेषः ॥ * ॥

(भाष्यम्) ब्राह्मणवत्साब्राह्मणीवत्सयोर्लिङ्गस्य अविभक्तिपरस्य विशेषवाचकत्वादेकशेषो न भविष्यति । यत्र लिङ्गं विभक्तिपरमेव विशेषवाचकं तत्रैकशेषो भवति । नात्र लिङ्गं विभक्तिपरमेव विशेषवाचकम् ॥

(प्रदीपः) विभक्तिपरस्येति । एकविभक्तावित्यनुवर्तते । तेन एकशेषनिमित्ते विभक्तौ परतो यत्र स्त्रीपुंसकृतो विशेषस्तत्रैकशेषः । इह तु तस्यां चान्तर्वर्तिन्यां च विभक्तावित्येकशेषाभावः ॥

(उद्द्योतः) एकशेषनिमित्तेति । सारूप्योपलक्षणत्वमेवात्र निमित्तत्वम् लिङ्गस्याविभक्तिपरस्येति भाष्ये पाठः ॥ लिङ्गस्य लिङ्गबोधकप्रत्ययस्य ॥ कैयटे विभक्तिपरस्येति प्रतीकग्रहणं तद्भनन्भाष्य आह—यत्र लिङ्गं विभक्तिपरमेवेति ॥ नात्र लिङ्गं विभक्तिपरमेवेति । अत एवानेकशेषे साध्ये हेतोः पक्षवृत्तित्वम् । अयमस्य सूत्रस्यार्थो यत्र प्रकृत्यतिरिक्तैकशेषनिमित्तविभक्तिपरशब्दगम्य एव स्त्रीत्वरूपो विशेषस्तत्रैकशेषो विभक्तौ सरूपाणामिति ॥ विभक्तौ सारूप्यं च लिङ्गबोधकातिरिक्तकृतमेव सामर्थ्याद्बोध्यम् ॥ स्त्रीपुंसकृत इति । स्त्रीपुंसबोधकशब्दकृतस्तद्गम्यो विशेषः स्त्रीत्वादिरूप इत्यर्थः ॥

(आक्षेपभाष्यम्)

यदि तर्हि यत्र लिङ्गं विभक्तिपरमेव विशेषवाचकं तत्रैकशेषो भवति, इह न प्राप्नोति कारकश्च कारिका च कारकौ । नह्यत्र लिङ्गं विभक्तिपरमेव विशेषवाचकम् । किं तर्हि ? । इत्वमपि ॥

(प्रदीपः) कारिका चेति । इत्वमप्यत्र विशेषस्य वाचकं तच्च नैकशेषनिमित्ते विभक्तौ परतोऽनन्तरमिति दोषः ॥

(उद्द्योतः) इत्वमप्यस्येति । सतीत्वे स्त्रीत्वप्रतीतेरित्यर्थः ॥ भाष्ये—लिङ्गं लिङ्गबोधकः शब्दः ॥

(समाधानाय विचारभाष्यम्)

कथं पुनरिदं विज्ञायते—शब्दो या स्त्री तल्लक्षणश्चेदेव विशेष इति, आहोस्विदर्थो या स्त्री तल्लक्षणश्चेदेव विशेष इति ? ॥

किं चातः ? ।

यदि विज्ञायते 'शब्दो या स्त्री तल्लक्षणश्चेदेव विशेष' इति, सिद्धम्—कारकश्च कारिका च

कारकौ। एवं तु न सिध्यति—गोमांश्च गोमती च गोमन्तौ॥

अथ विज्ञायते—'अर्थो या स्त्री तल्लक्षणश्चेदेव विशेषः' इति, सिद्धम्—गोमांश्च गोमती च गोमन्तौ। एवं तु न सिध्यति—'कारकश्च कारिका च कारकौ'। उभयथापि पटुश्च पट्वी च पटू इत्येतन्न सिध्यति॥

(प्रदीपः) एतत्समाधानार्थं विचारयति—**कथमिति**॥ **अर्थ इति**। अर्थस्त्रियाः शब्दद्वारकं विभक्तिपरत्वम्॥ **कारिका चेति**। शब्दस्त्रिया टापात्र कृतमित्वमिति सिध्यति, नार्थपक्षे। यद्यप्यर्थेन टाप् कृतः तथाप्यधिकमित्वमस्ति न च तदर्थस्त्रीकृतमिति दोषः॥ **गोमती चेति**। नात्र शब्दस्त्रिया कश्चिद्विशेषः कृतः। अर्थपक्षे त्वत्र सिध्यति। अर्थेनेकारस्य विशेषस्य कृतत्वात्॥ **पट्वी चेति**। नात्र यणादेशस्य लक्षणवाक्ये शब्दस्त्री निमित्तत्वेनोपात्ता। अजूपताश्रयणेन यणादेशविधानात्। न च तद्भावे भवतस्तन्निमित्तत्वं नाप्यर्थस्त्री यणादेशस्य निमित्तमिति दोषः॥

(उद्द्योतः) शब्दो या स्त्रीति सामर्थ्यात्तल्लक्षण इत्यस्य तन्निमित्तक इत्यर्थः॥ अर्थस्त्रीपक्षेऽप्येवमेव तदर्थं मन्यते तदाह—**न च तदिति**॥ **नात्र यणादेशस्येति**। अर्थशब्दान्यतरस्त्रीकृत एव यत्र विशेषो नान्यकृत इत्यर्थ इति भावः॥ **शब्दस्त्री निमित्तत्वेनेति**। स्त्रीप्रत्ययत्वेनेत्यर्थः॥

(समाधानभाष्यम्)

एवं तर्हि नैवं विज्ञायते शब्दो या स्त्री तल्लक्षणश्चेदेव विशेष इति, नाप्यर्थो या स्त्री तल्लक्षणश्चेदेव विशेष इति॥ कथं तर्हि?। शब्दार्थौ या स्त्री सद्भावेन च तल्लक्षणो विशेष आश्रीयते॥

(प्रदीपः) **शब्दार्थाविति**। नात्र यौगपद्येनोभयोर्ग्रहणम्। अनियमस्त्वनेन प्रदर्श्यते। तेन क्वचिच्छब्दस्त्रीकृतविशेषपरिग्रहः क्वचिदर्थस्त्रीकृतविशेषाश्रयणम्। पट्वीत्यत्र च भवतीकारो यणादेशस्य निमित्तमस्मिन्विषये तद्भावभावित्वादर्थोपि पारम्पर्येण भवत्येव निमित्तमित्वयणादेशयोः।

(उद्द्योतः) **नात्रेति**। यौगपद्यग्रहणे तूभयनिमित्तकस्य काप्यभावेन सूत्रासंगतिरेव स्यादिति भावः॥ भाष्ये **शब्दार्थौ या स्त्रीति**। साऽऽश्रीयते इति शेषः॥ नन्वेवमपि पटू इति न सिध्यति तत्राह—**सद्भावेन चेति**॥ तद्व्याचष्टे—**तद्भावभावित्वादिति**।

(आक्षेपभाष्यम्)

एवं च कृत्वा इहापि प्राप्तिः ब्राह्मणवत्सा च ब्राह्मणीवत्सश्चेति।

(उद्द्योतः) भाष्ये—**एवं च कृत्वेति**। अत्रार्थस्त्रीकृत एव विशेष इति भावः॥

(समाधानभाष्यम्)

एवं तर्हीदमिह व्यपदेश्यं सदाचार्यो न व्यपदिशति॥ किम्?। तदित्यनुवर्तते। तदित्यनेन प्रकृतौ स्त्रीपुंसौ प्रतिनिर्दिश्येते॥ कौ च प्रकृतौ?। प्रधाने। प्रधानं या शब्दस्त्री, प्रधानं या अर्थस्त्रीति॥ भ्रातृपुत्रौ स्वसृदुहितृभ्याम्॥ ६८॥

(प्रदीपः) **एवं तर्हीति**। विस्पष्टं न व्यपदिशतीत्यर्थः॥ सूत्रोपात्त एवायमर्थो येनात्र न भवत्येकशेष इत्याह—**तदित्यनेनेति**। स्त्रीपुंसयोः सहविवक्षायामेकशेषः। स च प्रधानयोरेव भवतीति यत्र प्रधानस्त्रीपुंसकृतो विशेषस्तत्रैकशेषः। इहाप्रधानकृतोपीत्येकशेषाभावः॥ ६८॥

(उद्द्योतः) **एवं तर्हीति**। स्त्रीरूपार्थस्य विभक्तिपरत्वं वक्तुमशक्यमिति भावः॥ **प्रधानस्त्रीपुंसकृत इति**। तत्कृत एवेत्यर्थः॥ ६८॥

(११७ एकशेषसूत्रम्॥ १। २। ३ आ. ६ सू.)

१४३ नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम्॥ १।२।६९॥

(प्रदीपः) **नपुंस**॥ ६९॥ शुक्ला च शुक्लं चेत्येकविभक्तौ विभक्त्यन्तानां च वैरूप्यादेकशेषो न प्राप्नोति, शुक्लश्च शुक्लं चेत्यत्रापि विभक्त्यन्तानामसारूप्यात्। एकविभक्तौ तु सरूपाणामेकशेषे पुन्नपुंसकयोः पर्यायेण प्राप्नोतीति वचनमिदमेकवद्भावार्थं च॥

(उद्द्योतः) **नपुंसकम्॥ ६९॥ पर्यायेणेति**। इदं चिन्त्यम् शुक्लानीत्यादौ नपुंसके प्रातिपदिकवैरूप्यात्। तस्मादप्राप्ते विधिरयमित्येव वक्तुमुचितम्॥

(प्रत्याख्यानभाष्यम्)

अयं योगः शक्योऽवक्तुम्॥

(आक्षेपभाष्यम्)

कथम्—शुक्लश्च कम्बलः शुक्लं च वस्त्रं तदिदं शुक्लं, ते इमे शुक्ले। शुक्लश्च कम्बलः शुक्ला च बृहतिका शुक्लं च वस्त्रं तदिदं शुक्लं तानीमानि शुक्लानि?॥

(७११ समाधानवार्तिकम्॥ १॥)

॥ * ॥ प्रधाने कार्यसंप्रत्ययाच्छेषः॥ * ॥

(भाष्यम्) **प्रधाने कार्यसंप्रत्ययाच्छेषो भविष्यति॥ किं च प्रधानम्?। नपुंसकम्॥ कथं पुनर्ज्ञायते नपुंसकं प्रधानमिति?। एवं हि दृश्यते लोके अनिर्ज्ञातेऽर्थे गुणसंदेहे च नपुंसकलिङ्गं प्रयुज्यते—किं जातमित्युच्यते। द्वयं चैव हि जायते। स्त्री वा**

पुमान्वा । तथा—विदूरे अव्यक्तरूपं दृष्ट्वा वक्तारो भवन्ति—महिषीरूपमिव ब्राह्मणीरूपमेव । प्रधाने कार्यसंप्रत्ययान्नपुंसकस्य शेषो भविष्यति ॥

(प्रदीपः) प्रधाने कार्यसम्प्रत्ययादिति । शब्देनार्थस्याभिधानमिह कार्यम् । तच्च नपुंसकानपुंसकसन्निधौ नपुंसकस्यैव भविष्यतीति नार्थः सूत्रेणेत्यर्थः ॥ कथमिति । यथा लोके बहुषु गच्छत्सु राजा गच्छतीति प्रधानं राजा व्यपदिश्यते । राज्ञश्च प्राधान्यं तदधीनप्रवृत्तिनिवृत्तित्वादन्येषाम् । इह तु नपुंसकस्य किंकृतं प्राधान्यमिति प्रश्नः ॥ एवं हि लोके दृश्यतइति । व्यापित्वान्नपुंसकस्य प्राधान्यमाह । स्थितिर्नपुंसकं सा च सर्वत्र विद्यत इति स्थितिरूपत्वेनैव स्त्रीपुंसयोरपि विवक्षायां सिद्धो नपुंसकशब्दप्रयोगः ॥ अनिर्ज्ञातेर्थे इति । सामान्यरूपेण ज्ञाते स्त्रीत्वादिना तु विशेषेणानिर्ज्ञात इत्यर्थः ॥ गुणसन्देह इति । गुणाः स्त्रीत्वादयः ॥ द्वयं चैवेति । यद्यपि नपुंसकस्य जन्म, तथापि यत्प्रजननासमर्थं तन्नपुंसकमिति नेह नपुंसकलक्षणं, किं तर्हि? शब्दैकगोचरत्वमेव लिङ्गलक्षणम् । तथा च नपुंसको भवतीति प्रयोग उपपद्यते ॥ महिषीरूपमिवेति । रूपशब्दः संस्थानवचनः । यत्र दूराद्दृश्यमाने वस्तुनि निश्चयो नास्ति केवलं सम्भावनारूपः सन्देहस्तत्रैकस्यापि शब्दस्य प्रयोगो भवति स्थाणुरयं स्यादिति । एवमिहापि महिषीवैतत् संस्थानमित्यस्मिन्नर्थे महिषीरूपमिवेति प्रयुक्तम् । रूपशब्दोत्र नपुंसकलिङ्गो दृष्टान्तत्वेनोपात्तः । यत्र तु विशेषस्य निर्ज्ञानं शुक्लाः शाट्यः शुक्लाः कम्बला इति तत्र नास्ति नपुंसकप्रयोगः ॥ सत्यारम्भे अरण्यारण्यान्याविलत्रैवकारानुवर्तनान्महत्त्वस्त्रोपाधेराधिक्यादेकशेषाभावः ॥ ६९ ॥

(उद्द्योतः) प्रधाने कार्यसंप्रत्ययादित्यस्य कार्यस्यैकशेषस्यैकावस्थानरूपस्य प्रधाने नपुंसके संप्रत्ययात्तस्यैव शेष इति नार्थः, योगप्रत्याख्याने हेतुत्वानुपपत्तेरत आह—शब्देनेति ॥ नपुंसकस्यैवेति । प्रधानन्यायेनेत्यादिः । प्रधानन्यायेन नपुंसकत्ववैशिष्ट्येनैव स्त्रीपुंसार्थस्यापि प्रतीतिरिति भावः ॥ स्थाचेति । वृद्धिह्रासयोः स्थितेरपि सत्त्वादिति भावः ॥ नन्वनिर्ज्ञाते कथं प्रश्नोऽत आह—सामान्यरूपेणेति ॥ भाष्ये अनिर्ज्ञातेर्थे गुणसन्देहे चेति । गुणसन्देहमूलकेऽनिर्ज्ञातार्थविषये प्रश्नवाक्ये इत्यर्थः ॥ शब्दैकगोचरत्वमिति । तत्तच्छब्दमात्रबोध्योपचयादिरूपत्वमेवेत्यर्थः । ततश्च नपुंसकस्य प्रजननासमर्थस्यापि पुंस्यन्तर्भावोस्तीति भाव इति विवरणकृतः ॥ स्त्री वा पुमान्वेत्यस्य स्त्रीशब्दवाच्यं पुंशब्दवाच्यं वेत्यर्थः ॥ एतद्भाष्यस्य प्रायेणेत्यादिरित्यन्ये ॥ नन्वनेककोटिकस्यैव सन्देहस्य दृष्टत्वेनेदृक् सन्देहाकारोऽनुचितोत आह—यत्र दूरादिति ॥ इत्यस्मिन्नर्थे इति ॥ इवशब्दो भिन्नक्रम इति भावः ॥ दृष्टान्तत्वेनेति । स्त्रीविषयो रूपशब्दो नपुंसके स्त्रिया अन्तर्भावे दृष्टान्तत्वेनोपात्त इत्यर्थः । एवं च व्यापकत्वेन नपुंसकस्य प्राधान्यात् तद्विवक्षायां नपुंसकप्रयोगः ॥ आधिक्यादिति । यदि विशेषस्तदा नपुंसकत्वस्त्रीत्वपुंस्त्वकृत एवेत्यर्थ इति भावः ॥

(आक्षेपभाष्यम्)

इदं तर्हि प्रयोजनम्—एकवच्चास्यान्यतरस्यामिति वक्ष्यामीति ॥

(समाधानभाष्यम्)

एतदपि नास्ति प्रयोजनम् ।

(७९२ समाधानवार्तिकम् ॥ २ ॥)

॥ * ॥ आकृतिवाचित्वादेकवचनम् ॥ * ॥

(भाष्यम्) आकृतिवाचित्वादेकवचनं भविष्यति यदा द्रव्याभिधानं तदा द्विवचनबहुवचने भविष्यतः ॥ नपुंसकमनपुंसकेनैक० ॥ ६९ ॥

(उद्द्योतः) आकृतिवाचित्वादिति । यदा आकृतौ स्वगतसंख्या विवक्षा तदेकवचनं, यदाश्रयगतसंख्यारोपस्तदापि द्विवचनादीति बोध्यम् । एतेन सरूपसूत्रविषयेप्येकवचनान्तत्वमनुमतं भगवतेति बोध्यम् ॥ ६९ ॥

(११८-११९ एकशेषसूत्रम् ॥ १।२। ३ आ. ७-८ सू.)

भ्रातृपुत्रौ स्वसृदुहितृभ्याम् ॥

१४४ पिता मात्रा ॥ ७० ॥

१४५ श्वशुरः श्वश्र्वा ॥ ७१ ॥

(सूत्रप्रयोजनाधिकरणम्)

(आक्षेपभाष्यम्)

किमर्थमिदमुच्यते । न "पुमान् स्त्रिया" इत्येव सिद्धम्? ॥

(प्रदीपः) पिता ॥ ७० ॥ किमर्थमिति । वृत्तिविषये भ्रात्रादिशब्दानां स्वस्रादिष्वपि वृत्त्या सिद्ध एकशेष इति मत्वा प्रश्नः ॥

(उद्द्योतः) पिता मात्रा ॥ ७० ॥ भ्रात्रादीनां वैरूप्यादभिन्नार्थत्वाच्चैकशेषाप्राप्तेः पुमान् स्त्रियेत्यत्रापि सरूपाणामित्यनुवृत्तेः प्रश्नानुपपत्तिमाशङ्क्याह—वृत्तीति । भाष्ये—न पुमान् स्त्रियेति सिद्धमिति । सरूपाणामित्यपेक्षया परत्वादयमेव न्याय्य इति भावः ॥ स्वस्रादिष्वपीति । एकापत्यत्वादेः प्रवृत्तिनिमित्तस्य सत्त्वादिति भावः ॥ एवं भ्राता च भ्रात्री चेति विग्रहे पुमान् स्त्रियेत्येव सिद्धमिति तात्पर्यम् ॥

(७९३ समाधानवार्तिकम् ॥ १ ॥)

॥ * ॥ भ्रातृपुत्रपितृश्वशुराणां कारणाद् द्रव्ये शब्दनिवेशः ॥ * ॥

(भाष्यम्) भ्रातृपुत्रपितृश्वशुराणां कारणाद् द्रव्ये शब्दनिवेशो भवति ।

(प्रदीपः) कारणादिति । भिन्नं च प्रवृत्तिनिमित्तं भ्रातृशब्दस्य स्वसृशब्दस्य चेति भ्रातृशब्देन न स्वसुरभिधानं प्राप्नोति ॥

(उद्द्योतः) भाष्ये उत्तरयति—भ्रातृपुत्रेत्यादि ॥ तद् व्याचष्टे—भिन्नं च प्रवृत्तिनिमित्तमिति । एतदेव भाष्ये कारणशब्देनोक्तम् । पुंस्त्वविशिष्टमेकापत्यत्वं भ्रातृशब्दस्य, स्त्रीत्वविशिष्टं स्वसृशब्दस्येत्यर्थः ॥ तयोः सारूप्याभावात्पुमान् स्त्रियेत्यस्याप्राप्तिरिति भावः ॥

(प्रत्याख्यानाधिकरणम्)

(७९४ प्रत्याख्यानवार्तिकम् ॥ २ ॥)

॥ * ॥ भ्रातृपुत्रपितृश्वशुराणां कारणाद् द्रव्ये शब्दनिवेश इति चेत्तुल्यकारणत्वात् सिद्धम् ॥ * ॥

(भाष्यम्) यदि तावद्बिभर्तीति भ्राता, स्वसर्यप्येतद्भवति ॥

तथा यदि पुनातीति प्रीणातीति वा पुत्रः, दुहितर्यप्येतद्भवति ॥

तथा यदि पाति पालयतीति वा पिता मातर्यप्येतद्भवति ॥

तथा यद्याश्वासत्व्यः श्वशुरः, श्वश्र्वामप्येतद्भवति ॥

(उद्द्योतः) प्रत्याख्यानवाधाह—इति चेत्तुल्येति ॥

(७९५ आक्षेपवार्तिकम् ॥ ३ ॥)

॥ * ॥ दर्शनं वै हेतुः ॥ * ॥

(भाष्यम्) नहि स्वसरि भ्रातृशब्दो दृश्यते ॥

(उद्द्योतः) आरम्भवाधाह—दर्शनं वै हेतुरिति ॥

(७९६ प्रत्याख्यानवार्तिकम् ॥ ४ ॥)

॥ * ॥ दर्शनं हेतुरिति चेत्तुल्यम् ॥ * ॥

(भाष्यम्) दर्शनं हेतुरिति चेत्तुल्यमेतद्भवति । स्वसर्यपि भ्रातृशब्दो दृश्यताम् । तुल्यं हि कारणम् ॥

(उद्द्योतः) प्रत्याख्यानवाधाह—दर्शनं हेतुरिति चेत्तुल्यमिति । दर्शनहेतोस्तुल्यत्वात्तत्रापि दर्शनं स्यादित्यर्थः ॥

(आक्षेपभाष्यवार्तिकम् ॥)

॥ नवै एष लोके सम्प्रत्ययः ॥

(भाष्यम्) नहि लोके भ्राता आनीयतामित्युक्ते स्वसा आनीयते ॥

(७९७ समाधानवार्तिकम् ॥ ५ ॥)

॥ * ॥ तद्विषयं च ॥ * ॥

(भाष्यम्) तद्विषयं चैतद् द्रष्टव्यं भवति । स्वसरि भ्रातृत्वम् ॥ किंविषयम् ? । एकशेषविषयम् ॥

(प्रदीपः) एकशेषविषयमिति । आरब्धे एकशेषेऽवश्यं भ्रातृशब्देन स्वसाभिधेया । अन्यथैकशेषारम्भोऽनर्थकः स्यात् । एवमनारब्धेप्येकशेषे नित्यत्वाच्छब्दार्थसम्बन्धस्य सहविवक्षायामेव भ्रातृशब्दः स्वसुरभिधायको भविष्यति । नह्यविद्यमानसम्बन्धस्य शक्तिः शास्त्रेण नियम्यते । अनभिधानाच्च भ्रातृपुत्रशब्दयोः स्वसृदुहितृभ्यां द्वन्द्वाभावः । मातापितरौ श्वश्रूश्वशुराविति द्वन्द्व इष्यत एव ॥ ७० ॥ ७१ ॥

(उद्द्योतः) शास्त्रारम्भेणेति पाठः ॥ नियम्यते उत्पाद्यते । एवं च भ्रातृत्वपुत्रत्वपितृत्वश्वशुरत्वादीनां स्वसृदुहितृमातृश्वश्रूष्वारोपेणैकशेषविषये तत्तद्रूपेणैव स्वस्रादीनां बोध इति सरूपसूत्रादिप्रत्याख्यानेपि न दोष इति तत्त्वम् ॥ एवं प्रत्याख्याता त्रिसूत्रीति दिक् ॥ ७० ॥

(आक्षेपभाष्यम्)

युक्तं पुनर्यन्नियतविषया नाम शब्दाः स्युः ॥

(समाधानभाष्यम्)

बाढं युक्तम् ।

(७९८ समाधानसाधकवार्तिकम् ॥ ६ ॥)

॥ * ॥ अन्यत्रापि तद्विषयदर्शनात् ॥ * ॥

(भाष्यम्) अन्यत्रापि नियतविषयाः शब्दा दृश्यन्ते । तद्यथा—समाने रक्ते वर्णे गौर्लोहित इति भवति, अश्वः शोण इति । समाने च काले वर्णे गौः कृष्ण इति भवति, अश्वो हेम इति । समाने च शुक्ले वर्णे गौः श्वेत इति भवति, अश्वः कर्क इति ॥ पिता मात्रा ॥ ७० ॥ श्वशुरः श्वश्र्वा ॥ ७१ ॥

(१२० एकशेषसूत्रम् ॥ १ । २ । ३ आ० ९ सू०)

१४६ त्यदादीनि सर्वैर्नित्यम् ॥१।२।७२॥

(शिष्टे लिङ्गवचननिर्णयाधिकरणम्)

(७९९ नियमवार्तिकम् ॥ १ ॥)

॥ * ॥ त्यदादितः शेषे पुन्नपुंसकतो लिङ्गवचनानि ॥ * ॥

(भाष्यम्) त्यदादितः शेषे पुन्नपुंसकतो लिङ्गवचनानि भवन्ति । सा च देवदत्तश्च तौ । सा च कुण्डे च तानि ॥

(प्रदीपः) त्यदादी ॥ ७२ ॥ त्यदादित इति । षष्ठ्या व्याश्रय इति तसिः । आद्यादित्वाद्वा ॥ सा चेति । स्त्रीत्वे प्राप्ते पुंस्त्वं विधीयते । पुंनपुंसकयोस्त्वेकशेषे शब्दपरविप्रतिषेधान्नपुंसकत्वं भवति ॥

(उद्द्योतः) त्यदादीनि ॥ ७२ ॥ व्याश्रय इति । त्यदादितद्भिन्नपक्षयोरेकशेषेण त्यदादिपक्षाश्रयणादत्रापि व्याश्रयसद्भावो बोध्यः ॥ त्यदादीनामित्यर्थः ॥ पुन्नपुंसकत इति । पुन्नपुंसकयोरित्यर्थः । सहविवक्षितपुन्नपुंसकवशेनेति भावः ॥ पुंस्त्वमिति । वचनं त्वभिधेयवशेन सिद्धमिति प्रसङ्गोच्चारितो वचनशब्दः ॥ शब्दपरेति । वार्तिके इति शेषः ॥ ध्वनितं चेदं नपुंसकमनपुंसकेनेतिसूत्रतत्प्रत्याख्यानभाष्याभ्याम् ॥ इदं वचनं त्यदादिभिः सजातीयविजातीयानां त्यदादीनां त्यदादिभिन्नानां च सहविवक्षायामेकशेषप्रवृत्तिविषयम्, अक्षरस्वारस्येन तथैव लाभात् । न चैवं गाव इमाश्चरन्तीत्युत्तरसूत्रस्थभाष्यप्रयोगे इमा इत्यनुपपन्नं स्यात् । निषेधवार्तिके द्वन्द्वपदेनैकशेषस्यापि ग्रहणात् ॥

(८०० पर्युदासवार्तिकम् ॥ २ ॥)

॥ * ॥ अद्वन्द्वतत्पुरुषविशेषणानाम् ॥ * ॥

(भाष्यम्) अद्वन्द्वतत्पुरुषविशेषणानामिति वक्तव्यम् ॥ इह माभूत्—स च कुकुटः सा च मयूरी, कुक्कुटमयूर्यौ ते । अर्द्धं पिपल्यास्तदर्धपिप्पली च साऽर्द्धपिप्पल्यौ ते ॥

(प्रदीपः) अद्वन्द्वतत्पुरुषविशेषणानामिति । न्यायसिद्धमिदम् । परवल्लिङ्गं द्वन्द्वतत्पुरुषयोरिति समासार्थस्य लिङ्गातिदेशात्तद्विशेषणस्यापि सर्वनाम्नस्तल्लिङ्गस्य सिद्धत्वात् ॥

(उद्द्योतः) तल्लिङ्गस्य सिद्धत्वादिति । प्रधानतन्त्रत्वाद् गुणानाम् ॥

(प्रत्याख्यानाधिकरणम्)

(प्रत्याख्यानभाष्यम्)

अयमपि योगः शक्योऽवक्तुम् । कथम् ? ।

(८०१ प्रत्याख्यानहेतुवार्तिकम् ॥ ३ ॥)

॥ * ॥ त्यदादीनां सामान्यार्थत्वात् ॥ * ॥

(भाष्यम्) त्यदादीनां सामान्यमर्थः । आतश्च सामान्यं देवदत्तेपि हि स इत्येतद्भवति, यज्ञदत्तेपि । त्यदादीनां सामान्यार्थत्वात् शेषो भविष्यति ॥

(प्रदीपः) सामान्यमर्थ इति । वस्तुमात्रं त्यदादिभिः परामृश्यत इति तदेवैषामर्थः ॥

(उद्द्योतः) ननु नेह गवादिवत्सामान्यमर्थ इत्यत आह—वस्तुमात्रमिति । अविवक्षितस्त्रीत्वपुंस्त्वाद्यवान्तरविशेषं परोक्षत्वाद्यनुगतीकृतं वस्तुमात्रमित्यर्थः । एवं चैकेनैव तच्छब्देनोभयोः प्रतीतिः सिद्धेत्येकशेषफलं सिद्धमित्यर्थः ॥ लिङ्गमपि लोकत एव सिद्धम्, तत्र च तात्पर्यतो निर्णय इति भावः ॥

(प्रयोजनान्तरभाष्यम्)

इदं तर्हि प्रयोजनम्—परस्य शेषं वक्ष्यामीति ।

(प्रदीपः) परस्येति । सति सूत्रे शब्दपरविप्रतिषेधः शक्यते आश्रयितुम् ॥

(उद्द्योतः) सति सूत्रे इति । त्यदादीनीत्यनेनानुपूर्वीविशेषयुक्तानां निर्देशात् । असति तु वचने निर्णायकस्य विप्रतिषेधस्य न प्रवृत्तिरिति भावः ॥ एतन्मूलकमेव पठ्यते—त्यदादीनां मिथः सहोक्तौ यत्परं तच्छिष्यत इति ॥

(८०२ प्रत्याख्यानहेत्वन्तरवार्तिकम् ॥ ४ ॥)

॥ * ॥ परस्य चोभयवाचित्वात् ॥ * ॥

(भाष्यम्) उभयवाचि परम् ॥

(उद्द्योतः) परस्य चेति भाष्ये । परस्यैवेत्यर्थः ॥ आरम्भवादिनापि परस्योभयवाचित्वमङ्गीकार्यमित्यर्थः ।

(८०३ प्रत्याख्यानहेतुवार्तिकम् ॥ ५ ॥)

॥ * ॥ पूर्वशेषदर्शनाच्च ॥ * ॥

(भाष्यम्) पूर्वस्य खल्वपि शेषो दृश्यते—स च यश्च तावानय यावानय इति ॥

(प्रदीपः) पूर्वशेषदर्शनाच्चेति । सति त्वारम्भे पूर्वशेषो न स्यादिति दोषप्रसङ्गः ॥

(प्रयोजनान्तरभाष्यम्)

इदं तर्हि प्रयोजनम्—द्वन्द्वो मा भूदिति ॥

(प्रयोजनान्तरनिराकरणम्)

एतदपि नास्ति प्रयोजनम् ।

(८०४ प्रयोजनप्रत्याख्यानवार्तिकम् ॥ ६ ॥)

॥ * ॥ सामान्यविशेषवाचिनोश्च द्वन्द्वाभावात् सिद्धम् ॥ * ॥

(भाष्यम्) सामान्यविशेषवाचिनोश्च द्वन्द्वो न भवतीति वक्तव्यम् ॥

(प्रदीपः) द्वन्द्व इति । तदेवदत्ताविल्यादिप्रयोगो मा भूदित्यर्थः ॥

(उद्द्योतः) तद्देवदत्ताविति । अवान्तरधर्मविवक्षायां तत्प्राप्तिरिति बोध्यम् ॥

(इष्टानुपपत्तिभाष्यम्)

यदि सामान्यविशेषवाचिनोर्द्वन्द्वो न भवतीत्युच्यते, शूद्राभीरं गोबलीवर्दं तृणोलपमिति न सिध्यति ॥

(अनुपपत्तिपरिहारभाष्यम्)

नैष दोषः । इह तावच्छूद्राभीरमिति, आभीरा जात्यन्तराणि ॥

(प्रदीपः) आभीरा इति ।
'ब्राह्मणादुग्रकन्यायामाभीरो नाम जायते ।
माहिष्योग्रौ प्रजायेते विट्शूद्राङ्गनयोर्नृपात्' इति स्मृतिः ॥

(द्वितीयोदाहरणनिराकरणभाष्यम्)

गोबलीवर्दमिति । गाव उत्कालितपुंस्का वा-

ह्याय च विक्रयाय च स्त्रिय एवावशिष्यन्ते ॥

(प्रदीपः) **स्त्रिय एवेति**। ततश्चात्र गोशब्दः स्त्रीगवीणामेव वाचकः ॥

(उद्द्योतः) भाष्ये उत्कालिता निष्काशिताः पुरुषा येष्वित्यर्थः ॥ विनाशितपुंस्त्वा इत्यर्थं कश्चित्। तन्न। उत्तरसूत्रे पुंस उत्कालयितुमिति भाष्यासंगतेः ॥ किमर्थं पुंसां निष्काशनमत आह—वाह्यायचेति। प्रायेण बलीवर्दा एव वाह्यन्ते विक्रीयन्ते च ॥ **स्त्रिय एवेति**। ततश्च गोशब्दे स्त्रीत्वसमानाधिकरणं गोत्वं प्रवृत्तिनिमित्तं पुंस्त्वसमानाधिकरणं चेति नानार्थो गोशब्दः। तत्राद्यः प्रसिद्धोऽन्यस्तु कचिदेव। एवं च गोशब्दः स्त्रीगवीणामेव वाचकः प्रायेण, कचिदेव तात्पर्यग्राहकवशेन पुंगवानां वाचको, यथा **एतान् गाश्चतुरो** बलीवर्दान् पश्येति प्रथमयोरितिसूत्रस्थभाष्यप्रयोगे गौर्वाहीक इत्यादौ चेति भावः ॥ एवं च बलीवर्दसमभिव्याहाराद् गोशब्दस्तदतिरिक्तपर इति कथा चिन्त्या ॥ वाह्यार्थं निष्काशितपुरुषा एव गावो गोपदवाच्या न तु तत्सहिता इत्यर्थो भाष्यस्य ॥ **एतान् गा** इत्युदाहरणे बलीवर्दानिति त्ववस्याविशेषप्राप्तत्वबोधनायेत्याहुः ॥ **ततश्चात्रेति**। अत्रोदाहरणे पुंतात्पर्यग्राहकरहिते इत्यर्थः। भाष्यात् लोकाच्च गोशब्दव्यवहारः प्रायेण स्त्रीगवीष्वेवेति द्रष्टव्यम् ॥

(तृतीयोदाहरणनिराकरणभाष्यम्)

तृणोलपमिति अपामुलपमिति नामधेयम् ॥

(तटस्थाक्षेपभाष्यम्)

तत्तर्हि वक्तव्यम् ॥

(समाधानभाष्यम्)

न वक्तव्यम्। सामान्येनोक्तत्वाद्विशेषस्य प्रयोगो न भविष्यति। सामान्येनोक्तत्वात् तस्यार्थस्य, विशेषस्य प्रयोगेण न भवितव्यम्। किं कारणम्?। उक्तार्थानामप्रयोग इति ॥

(प्रदीपः) **सामान्येनेति**। सर्वविशेषाणां व्याप्तत्वाभास्ति सामान्यविशेषयोः समुच्चय इत्यर्थः ॥

(उद्द्योतः) **समुच्चय इति**। सहविवक्षेत्यर्थः ॥

(आक्षेपभाष्यम्)

न तर्हीदानीमिदं भवति—तं ब्राह्मणमानय गार्ग्यमिति ॥

(प्रदीपः) **तं ब्राह्मणमिति**। तमित्यनेन गतत्वाद्ब्राह्मणशब्दस्य प्रयोगो न प्राप्नोति ब्राह्मणमित्यनेन गतत्वाच्च गार्ग्यशब्दस्येति भावः ॥

(उद्द्योतः) **गतत्वादिति**। वस्तुमात्रविवक्षयेत्यर्थः ॥

(आक्षेपशेषभाष्यम्)

भवति। यदा नियोगतस्तस्यैवानयनं भवति ॥

(प्रदीपः) **भवतीति**। सामान्योपक्रमे विशेषाभिधानमित्यर्थः ॥

(उद्द्योतः) **सामान्योपक्रमे इति**। न प्रथमत एव विशेषावगमः। तथा सति सामान्यविशेषवाचिनोरुभयोः प्रयोगवैयर्थ्यम्। तस्मात्सामान्योपक्रमे विशेषाभिधानमित्यर्थः ॥

(समाधानभाष्यम्)

एवं तर्हि येनैव खल्वपि हेतुना एतद्वाक्यं भवति-तं ब्राह्मणमानय गार्ग्यमिति, तेनैव हेतुना वृत्तिरपि प्राप्नोति। तस्मात्सामान्यविशेषवाचिनोर्द्वन्द्वो न भवतीति वक्तव्यम् ॥ त्यदादीनि ॥७२॥

(प्रदीपः) **येनैवेति**। यथा सामान्यविशेषयोर्विशेषणविशेष्यभावो दृश्यते तथा विशेषसंनिधौ तद्वर्जितेषु विशेषान्तरेषु सामान्यशब्दस्य वृत्तिर्दृश्यते—**ब्राह्मणा आयाता वसिष्ठोप्यायात** इति। तस्मात्तथाविधे विषयेऽयं वाचनिको द्वन्द्वनिषेधः। तस्मिंश्च सत्ययमेकशेषो न वक्तव्य इत्यर्थः॥७२॥

(उद्द्योतः) ननु वाक्यं विशेषणविशेष्यविषयम्, द्वन्द्वस्तूभयपदार्थप्रधानविषय इति कथमेतदत आह—**यथेति**। **प्राप्नोति**रन्तेष्विति तु सौत्रो निर्देशः। प्रमाणप्रमेयेत्यादि त्वेतद्भाष्यरीत्याऽसाध्वेवेत्याहुः ॥ ७२ ॥

(१२१ एकशेषसूत्रम् ॥ १।२।३ आ० १० सूत्रम्)

१४७ ग्राम्यपशुसंघेष्वतरुणेषु स्त्री १।२।७३ ॥

(प्रदीपः) **ग्राम्य** ॥ ७३ ॥ स्त्रीपुंसात्मकस्य संघस्य स्त्रीशब्देनाभिधानं यथा स्यादिति सूत्रारम्भः ॥

(उद्द्योतः) **ग्राम्यपशु** ॥ ७३ ॥ **स्त्रीशब्देनेति**। अन्यथा पुमान् स्त्रियेति पुंसः शेषः स्यादित्यर्थः ॥

(प्रत्याख्यानभाष्यम्)

अयमपि योगः शक्योऽवक्तुम् ॥

(प्रदीपः) उभयात्मकत्वमक्षाम्यन्नाह—**अयमिति** ॥

(उद्द्योतः) उभयेति । संघस्येत्यादिः ॥

(आक्षेपभाष्यम्)

कथम्—गाव इमाश्चरन्ति अजा इमाश्चरन्ति? ॥

(आक्षेपबाधकभाष्यम्)

गाव उत्कालितपुंस्का वाहाय च विक्रयाय च । स्त्रिय एवावशिष्यन्ते ॥

(प्रदीपः) स्त्रिय एवेति । यद्यपि तत्र वृषभस्यापि संभवः तथापि मल्लग्रामवद्भूयस्त्वात् स्त्रीभिर्व्यपदेशो भवति । अग्राम्यादिषु तु मिश्रत्वात् संघस्य पुमान् स्त्रियेति पुंसः शेषः॥

(उद्द्योतः) वृषभस्यापीति । सर्वेषामुत्कालनासंभवादिति भावः ॥ मिश्रत्वादिति । तेषामुभयसाधारणजातिविशिष्ट एव शक्तिरिति भावः ॥ ७३ ॥

(प्रयोजनान्तरभाष्यम्)

इदं तर्हि प्रयोजनम्—ग्राम्येष्विति वक्ष्यामीति । इह मा भूत्—न्यङ्कव इमे सूकरा इम इति ॥

(प्रयोजननिराकरणभाष्यम्)

कः पुनरर्हति अग्राम्याणां पुंस उत्कालयितुं, ये ग्रहीतुमशक्याः । कुत एव वाहाय च विक्रयाय च ॥

(प्रयोजनान्तरभाष्यम्)

इदं तर्हि प्रयोजनम्—पशुष्विति वक्ष्यामीति । इह मा भूत्—ब्राह्मणा इमे, वृषला इमे ॥

(प्रयोजननिराकरणभाष्यम्)

कः पुनरर्हत्यपशूनां पुंस उत्कालयितुं ये अशक्या वाहाय च विक्रयाय च ॥

(प्रयोजनान्तरभाष्यम्)

इदं तर्हि प्रयोजनम्—संघेष्विति वक्ष्यामीति । इह मा भूत्—एतौ गावौ चरतः ॥

(प्रयोजननिराकरणभाष्यम्)

कः पुनरर्हति निर्ज्ञातेऽर्थे अन्यथा प्रयोक्तुम् ।

(प्रयोजनान्तरभाष्यम्)

इदं तर्हि प्रयोजनम्—अतरुणेष्विति वक्ष्यामीति । इह मा भूत्—उरुणका इमे, बर्करा इम इति ॥

(प्रयोजननिराकरणभाष्यम्)

कः पुनरर्हति तरुणानां पुंस उत्कालयितुं ये अशक्या वाहाय च विक्रयाय च ॥

(८०५ शेषपूरणवार्तिकम् ॥ १ ॥)

॥ * ॥ अनेकशफेषु ॥ * ॥

(भाष्यम्) अनेकशफेष्विति वक्तव्यम् । इह मा भूत् । अश्वाश्चरन्ति, गर्दभाश्चरन्तीति ॥ ग्राम्यपशु ॥ ७३ ॥

इति श्रीमद्भगवत्पतञ्जलिविरचिते व्याकरणमहाभाष्ये प्रथमस्याध्यायस्य द्वितीयपादे तृतीयमाह्निकम् ॥

पादश्चायं समाप्तः ॥

(प्रदीपः) अनेकशफेष्विति । उष्ट्राणां त्वारण्यकत्वात् स्त्रीशेषाभावः । तत्रानेन प्रकरणेन प्रयोगस्य नियतत्वाद् जातिः क्वचिदाश्रयलिङ्गेन स्त्रीत्वेन व्यपदिश्यते क्वचित्पुंस्त्वेनेत्युक्तं भवति ॥ ७३ ॥

इत्युपाध्यायजैयटात्मजकैयटकृते महाभाष्यप्रदीपे प्रथमस्याध्यायस्य द्वितीये पादे तृतीयमाह्निकम् ॥

(उद्द्योतः) इति शिवभट्टसुत सतीगर्भज नागोजी (नागेश) भट्टकृते भाष्यप्रदीपोद्द्योते प्रथमस्य द्वितीये पादे तृतीयमाह्निकम् ॥

पादश्च द्वितीयः समाप्तः ॥

प्रथमाध्यायस्य तृतीये पादे प्रथमाह्निकम्

(आदितस्त्रयोदशमाह्निकम्)

(१२२ धातुसंज्ञासूत्रम् ॥ १ । ३ । १ आ. १ सू०)

१४८ भूवादयो धातवः १।३।१ ॥

(वकारस्य प्राप्तिप्रयोजननिरूपणम्)

(आक्षेपभाष्यम्)

कुतोयं वकारः । यदि तावत्संहितया निर्देशः क्रियते, भ्वादय इति भवितव्यम् । अथासंहितया, भूआदय इति भवितव्यम् ? ॥

(प्रदीपः) भूवादयो धातवः ॥ १ ॥ **कुतोयमिति ।** लक्षणाभावं मत्वा कस्मान्निमित्ताद्वकार इति पृच्छति ॥ **यदि तावदिति ।** यणादेशेनेको निवर्तितत्वात् ॥ **अथासंहितयेति ।** अभ्युपगम्यवादोयम् । न ह्येकस्मिन्पदेऽसंहितास्ति । **संहितैकपदे नित्येति** वचनात् । तस्मात्सर्वथा निर्देशो न संभवतीत्येवंपरमेतत् ॥

(उद्द्योतः) ॥ श्रीगणेशाय नमः ॥ भूवादयो ॥ १ ॥ **कस्मान्निमित्तादिति ।** फलमपि निमित्तम् । अत एव मङ्गलार्थ प्रत्युत्तरं सङ्गच्छते । तत्रेण कारणप्रश्नश्च । अत एव **यदि तावदिति** भाष्योक्तो विकल्पः सङ्गच्छते । न च भ्वादय इत्युक्तेपि वकारस्य सत्त्वात् प्रश्नानुपपत्तिरत आह—**यणेति ।** ऊकारोत्तरवकारविषयः प्रश्न इति भावः ॥ असाद्भाष्यात्समासेपि संहिताविकल्प इति भ्रमं वारयति—**अभ्युपगम्येति ॥ न ह्येकस्मिन्निति ।** यद्यप्यत्र संहितानित्यत्वे नैकपदत्वं प्रयोजकं

"संहितैकपदे नित्या नित्या धातूपसर्गयोः ।
नित्या समासे वाक्ये तु सा विवक्षामपेक्षते" ॥

इतिश्लोके समासग्रहणेनैकपदशब्देनाखण्डपदस्यैव ग्रहणात् । अत एवाग्रेअग्र इत्यादावाष्टमिकद्वित्वे सा न नित्या, किं तु समासत्वं प्रयोजकम् । तथाप्यनेनैकदेशेनोक्तश्लोकग्रहणान्न दोषः ॥ नन्वेवं भाष्यप्रामाण्योच्छेदोत आह—**तस्मादिति ।** तथा च तात्पर्यविषयाबाधान्नाप्रामाण्यमिति भावः ॥

(समाधानभाष्यम्)

अत उत्तरं पठति—

(८०६ समाधानवार्तिकम् ॥ १ ॥)

॥ * ॥ भूवादीनां वकारोयं मङ्गलार्थः प्रयुज्यते ॥ * ॥

(भाष्यम्) माङ्गलिक आचार्यो महतः शास्त्रौघस्य मङ्गलार्थं वकारमागमं प्रयुङ्क्ते । मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि शास्त्राणि प्रथन्ते वीरपुरुषाणि भवन्ति आयुष्मत्पुरुषाणि च, अध्येतारश्च मङ्गलयुक्ता यथा स्युरिति ॥

(प्रदीपः) **भूवादीनामिति ।** सूत्रोच्चारिते भूवादिशब्दे इत्यर्थो विवक्षितः । तत्र वाचकसंबन्धी भूवादीनां भूवादिशब्दवाच्यानां वकार इति व्यपदिश्यते ॥ **मङ्गलार्थ इति ।** ननु निमित्ते पृष्टे प्रयोजनकथनमप्रस्तुतम् । नैष दोषः । प्रयोजनकथनेन निमित्तस्यापि कथनात् । अत एव निपातनादागमरूपोत्र वकारः कृतः । न चायमसाधुः । वैयाकरणनिकाये प्रसिद्धत्वात् । तस्य च मङ्गलं प्रयोजनमित्यनेन प्रतिपादितं भवति । अपूर्वस्य हि लाभो दध्यादेर्लोके मङ्गलं सूचयति । तथेहाप्यागमो वकारो मङ्गलार्थः संपद्यते । अथ वा सति वकारेऽविकृते भूशब्दे उच्चार्यमाणे महाव्याहृतिस्मरणं मङ्गलं भवतीति पारम्पर्येण वकारो मङ्गलार्थकः संपद्यते ॥

(उद्द्योतः) ननु भूवादीनामित्यस्य स्वरूपपरत्वे बहुवचनानुपपत्तिरर्थपरत्वे प्रकृतासङ्गतिरतः पर्यवसितमर्थमाह—**सूत्रोच्चारिते इति ॥** तद्राभप्रकारमाह—**तत्रेति ।** वाचकभूवादिशब्दसंबन्धी वकारस्तद्वाच्यनिष्ठत्वेनोपचर्यत इति भावः ॥ **प्रयोजनेति ।** अनिमित्तकस्यासत्प्रायतया प्रयोजनकथनानुपपत्तिरिति भावः ॥ उभयस्मिन् पृष्टे प्रयोजनमात्रकथनमसङ्गतमित्यपि बोध्यम् ॥ **न चायमिति ।** सर्वलोकप्रयुक्तत्वाभावादिति भावः ॥ **वैयाकरणेति ।** अनादिव्यवहार एव साधुत्वप्रयोजको न सर्वलोकप्रसिद्धिः । अन्यथा याज्ञिकमात्रप्रसिद्धस्फ्यादीनां व्याकरणप्रसिद्धटिघुभादीनामप्यसाधुत्वापत्तिरिति भावः ॥ ननु मङ्गलं नाम धर्मः तत्र न वकारोच्चारणं तज्जनकं मानाभावाद् भ्वादिशब्देनापि तत्सम्भवाच्चात आह—**अपूर्वस्य हीति ।** मङ्गलजनक इति नार्थः, किं तु सूचक इति न दोषः । निबन्धनं तु शिष्याणामप्यानुपक्रिकमङ्गलसूचनार्थमिति भावः ॥ नन्वस्य मङ्गलसूचकापूर्ववस्तुत्वं न लोकसिद्धमत आह—**अथ वेति ॥** रेफान्तस्यैव महाव्याहृतित्वादाह—**स्मरणमिति ।** एवं च वकारलक्षणप्रश्ने इदमेव निपातनविषया लक्षणम् । गुरूच्चारणं तु महाव्याहृतिस्मरणलक्षणमङ्गलार्थमित्युत्तरमिति बोध्यम् ॥ तदेतत्सर्वं भाष्ये **वकारमागमम्**ित्यनेन सूचितम् ॥ वैकारस्यामृतबीजत्वादध्यादिवन्मङ्गलसूचकत्वमित्यन्ये ॥

(आक्षेपभाष्यम्)

(आदिग्रहणप्रयोजनवर्णनाधिकरणम्)

अथादिग्रहणं किमर्थम् । यदि तावत्पठ्यन्ते नार्थ आदिग्रहणेन । अन्यत्रापि ह्ययं पठन्नादिग्रहणं न करोति ॥ क्वान्यत्र ? । "मृडमृदगुधकुषक्लिशवदवसः क्त्वा" इति ॥

अथ न पठ्यन्ते नतरामर्थ आदिग्रहणेन। नह्यपठिताः शक्या आदिग्रहणेन विशेषयितुम् ॥

(प्रदीपः) **नार्थ इति।** **भूवादीन्** पठित्वा 'ते धातवः' इति वक्तव्यम्, यथा **ते तद्राजा** इति ॥ **नतरामिति।** सति पाठे गतार्थत्वान्न कर्तव्यम्। असति त्वसंबन्धादित्यर्थः ॥ अत एव प्रतिषेधप्रकर्षः। संबन्धाभावेत्यन्तमेवाकरणमित्यस्यार्थस्य प्रतिपत्तये निर्दिष्टः ॥

(उद्योतः) ननु गणपाठेप्यादिग्रहणं विना कथं सर्वसंग्रहोऽत आह—**भूवादीनिति।** एवं च भूपदस्थाने 'ते' पदस्यावश्यकतया आदिपदमात्रविषयः प्रश्नो भाष्ये कृत इति भावः ॥ **इन्धिभवतिभ्यां चेति** भवतिमादिं मन्यते ॥ **अत्यन्तमेवेति।** अनेन सति पाठे संनिधानाविशेषाद्धातूनामिव प्रत्ययानामपि तत्पदं परामर्शकं स्यादिति ज्ञापकक्लेशवारणाय स्पष्टप्रतिपत्तये आदिग्रहणं कदाचित् क्रियेतेति नात्यन्तमकरणमिति सूचितम् ॥

(समाधानभाष्यम्)

एवं तर्हि सिद्धे सति यदादिग्रहणं करोति, तज्ज्ञापयत्याचार्यः—'अस्ति च पाठो बाह्यश्च सूत्राद्' इति ॥ किमेतस्य ज्ञापने प्रयोजनम्? ॥ पाठेन धातुसंज्ञेत्येतदुपपन्नं भवति ॥

(प्रदीपः) **एवं तर्हीति।** सूत्रेषु ये पठ्यन्ते मृडमृदादयः तान्समाप्य 'ते धातव' इति वचनेन सिद्धे सतीत्यर्थः ॥ **अस्ति च पाठ इति।** अनेनासंबद्धत्वं परिहृतम्। बाह्यश्चेत्यनेन गतार्थत्वं निराकृतम् ॥ **पाठेनेति।** ये धातुपाठे पठितास्तेषामेव धातुसंज्ञा। तेषां च पाठो नोपलक्षणार्थः। अपि तु इयत्ताप्रतिपादनार्थः। तत्र यदि **क्रियावाची धातुरित्ये**तल्लक्षणं क्रियेत, तर्हि आणवयति वट्यतीत्यादीनामपि धातुसंज्ञा स्यात्। अथ सूत्रपठितानामनन्तरं **ते धातव** इत्युच्येत, तदा तत्रापठितानां न स्यात्। तस्माद्भूवादय इत्युक्तम्। तत्र सूत्रवार्तिकभाष्यगणेषु ये पठ्यन्ते तेपि सूत्रकारादिप्रामाण्याद्धातुत्वेनाश्रयणीयाः ॥

(उद्योतः) नन्वेवमेवं **तर्हि सिद्धे** इति भाष्यमनुपपन्नं सूत्रपठितकतिपयानां धातुत्वसिद्धावपि सर्वेषां तत्सिद्ध्यभावादत आह—**सूत्रेष्विति** ॥ पूर्वपक्षी बहिर्गणपाठं न जानात्येवेतीन्धिभवतिभ्यां चेतिसूत्रस्थं भवतिमादिं मन्यत इति तं प्रत्याह सिद्धान्ती—यदि तावतामेव धातुत्वमिष्टं स्यात्तर्हि **ते धातव** इत्येव वदेदित्यादिग्रहणं ज्ञापकमिति भावः ॥ न च प्रकारवाच्यप्यादिशब्दो दृष्ट इति कथं ज्ञापकत्वं, व्यवस्थावाच्यादिशब्दस्य प्रसिद्धतरत्वादिति भावः ॥ ननु **बाह्यः पाठ** इत्येतावतैव सत्ताया अपि सिद्धेरस्ति **पाठ** इति व्यर्थमत आह—**अनेनेति।** यथा चादिग्रहणाकरणे पाठेन संज्ञेत्येतदुपपत्तिस्तथा दर्शयति—**ये धातुपाठ इति** ॥ यद्यपि **ते** इति पाठेपि पाठमूलैव संज्ञा तथापि पाठविशेषमूलत्वज्ञापनं ज्ञापकफलमिति भावः ॥ ननु ऋतिप्रभृतीनां सौत्राणां धातुत्वाय भ्वादेराकृतिगणत्वमावश्यकमित्याणवयत्यादावतिप्रसङ्गोत आह—**तेषां चेति।** अत एव भ्वादिसमाप्तौ वृत्करणम्। बहुलमेतन्निदर्शनमित्यपि यदि प्रामाणिकं तर्हि णिच एव तत्, न गणपाठस्येति भावः। ध्वनितं चेदं **पाठेन धातुसंज्ञेत्येत**द्भाष्येण ॥ ननु याः पश्यतीत्यादिव्यावृत्त्यर्थं क्रियावचनत्वस्यावश्यवाच्यतया पाठफलं नास्तीत्यतस्तत्फलं दर्शयति—**तत्रेति।** आज्ञापयतीत्यर्थे आणवयतीति प्राकृतम्। अपभ्रंशानामपि स्वातन्त्र्येणैव बोधकत्वाङ्गीकारादेतेषां क्रियावाचित्वं बोध्यम् ॥ अथ पाठविशेषफलं दर्शयति—**अथ सूत्रेति** ॥ ननु पाठस्यानुपलक्षणत्वे ऋत्यादीनां कथं धातुत्वमत आह—**सूत्रेति।** ऋतेरीयङिति सूत्रम् ***अनेकाज्ग्रहणं चुलुम्पाद्यर्थम्*** इति वार्तिकम्, गणः कण्ड्वादिर्धात्वधिकारविहितकार्योद्देश्यताकरणरूपं तत्प्रामाण्यं, तेन च पूर्वं धातुपाठे पठितानामिदानीं पाठभ्रंशोऽनुमीयत इति भावः ॥ नन्वेवमप्यवश्यं पठनीये गणे सूत्रान्तरे च गणं पठित्वा ते धातव इत्येव किं नोक्तमिति चेन्न। एवंविधसूत्रकरणेऽल्पाक्षरमसन्दिग्धमिति सूत्रलक्षणोच्छेदापत्तिः। अन्यथा सर्वादीनपि सूत्रान्तः पठित्वा सर्वनामानीत्याद्युक्त्यैव सिद्धे बहुव्याकुलतापत्तिरित्याहुः ॥

(अनिष्टापत्तिवारणाधिकरणम्)

(८०७ आक्षेपवार्तिकम् ॥ २ ॥)

॥ * ॥ पाठेन धातुसंज्ञायां समानशब्दप्रतिषेधः ॥ * ॥

(भाष्यम्) **पाठेन धातुसंज्ञायां समानशब्दानां प्रतिषेधो वक्तव्यः। या इति धातुः, या इत्याबन्तः। वा इति धातुः, वा इति निपातः। नु इति धातुः, नु इति प्रत्ययश्च निपातश्च। दिव् इति धातुः, दिविति प्रातिपदिकम् ॥**

किं च स्याद् यद्येतेषामपि धातुसंज्ञा स्यात्?। धातोरिति तव्यदादीनामुत्पत्तिः प्रसज्येत ॥

(प्रदीपः) **समानशब्दानामिति।** समानश्रुतीनामिष्टविपरीतानामक्रियावाचिनामित्यर्थः ॥ **तव्यदादीनामिति।** यथैव दिवं पश्येति बाह्यक्रियापेक्षे कर्मणि द्वितीया भवति, एवं तव्यदादयोपि स्युरित्यर्थः ॥

(उद्योतः) ननु समानशब्दानामित्यत्रार्थतः साम्ये पर्यायाणामित्यर्थेऽसंगतिः पर्यायातिप्रसङ्गस्य पाठाश्रयणप्रयुक्तत्वाभावादत आह—**समानश्रुतीनामिति** ॥ ननु प्रयोगस्थानां गणपठितेभ्यो भिन्नत्वेन समानश्रुतित्वेनैव कार्यस्य वक्तव्यत्वादाह—**इष्टेति** ॥ इष्टानिष्टविभागस्य दुर्ज्ञेयत्वादाह—**अक्रियेति** ॥ नन्वेषामक्रियावाचित्वात्कारके विधीयमानतव्यादीनां कथं प्राप्तिरत आह—**यथैवेति** ॥

(आक्षेपबाधकभाष्यम्)

नैष दोषः। साधने तव्यदादयो विधीयन्ते। साधनं च क्रियायाः। क्रियाभावात्साधनाभावः।

साधनाभावात्सत्यामपि धातुसंज्ञायां तव्यदादयो न भविष्यन्ति ॥

(प्रदीपः) साधन इति । अन्तरङ्गधातुवाच्यक्रियापेक्षे साधने तव्यदादयः सावकाशा बाह्यक्रियापेक्षे [साधने] नोत्पद्यन्ते इत्यर्थः । यो पि शकधृषेति स्वार्थिकस्तुमुन् सोप्यनभिधानान्न भविष्यति ॥

(उद्द्योतः) अन्तरङ्गेति । प्रातिपदिकाद् द्वितीयेत्यादौ प्रातिपदिकार्थनिरूपितकर्मासम्भवात्तथा ग्रहणेपि धातोस्तव्यदित्यादिवाक्ये उपस्थितधात्वर्थापेक्षकारकसम्भवान्न बाह्यग्रहणमिति भावः । अनया रीत्या भावेप्यनुत्पत्तिर्बोध्या । साध्यावस्थस्यैव तव्यदादिविधौ भावपदार्थत्वात् ॥ भाष्ये—साधनइति भावोपलक्षणं बोध्यम् । भावे इति यद्यपि न पदरुजादिसाहचर्यात्साध्यत्वेनापि भासमाने भावे एतद्विधानादित्याहुः ॥ नन्वेवमपि स्वार्थिकास्तुमुनादयः स्युरत आह—योपीति ॥ तादर्थ्ये तुमुनः क्रियार्थक्रियोपपदस्याभावादप्रसक्तेराह—शकेति ॥ वस्तुतोऽव्ययकृतो भाव इत्युक्तेः सोपि भाव एवेति बोध्यम् ॥

(आक्षेपसाधकभाष्यम्)

इदं तर्हि याः पश्य—"आतो धातोः" इति लोपः प्रसज्येत ॥

(प्रदीपः) याः पश्येति । यच्छब्दो न धातुरिति विभक्तिरुत्पद्यते तस्यामत्वे टापि च कृते धातुसंज्ञायामातो धातोरिति लोपप्रसङ्गः ॥

(उद्द्योतः) ननु धातुत्वे विभक्त्यनुत्पत्तिरेव कुतो न शङ्कितेत्यत आह—यच्छब्द इति ॥

(आक्षेपबाधकभाष्यम्)

नैष दोषः । "अनापः" इत्येवं सः ॥

(उद्द्योतः) अनाप इत्येवमिति भाष्ये । अत एव क्त्वः क्ष इत्यादिसिद्धिरिति भावः ॥ न च लक्षणप्रतिपदोक्तपरिभाषया टाबन्तस्य न धातुसंज्ञेति वाच्यम् ।

सकारजः षकारश्च षोट्टवर्गस्तवर्गजः ॥

इत्यभियुक्तोक्तेर्भूवादिसूत्रे तत्परिभाषाप्रवृत्तेर्वक्तुमशक्यत्वादित्याहुः ॥

(आक्षेपसाधकभाष्यम्)

अस्य तर्हि वाशब्दस्य निपातस्याधातुरिति प्रातिपदिकसंज्ञायाः प्रतिषेधः प्रसज्यते । अप्रातिपदिकत्वात्स्वाद्युत्पत्तिर्न स्यात् ॥

(आक्षेपबाधकभाष्यम्)

नैष दोषः । निपातस्यानर्थकस्य प्रातिपदिकत्वं चोदितं तत्रानर्थकग्रहणं न करिष्यते । "निपातः प्रातिपदिकम्" इत्येव ॥

(उद्द्योतः) भाष्ये तत्रानर्थकग्रहणं न करिष्यत इति । यौग स्वनिष्पर्थं तद् । वादिष्वधातुरिति बाधकबाधनार्थमपीति भावः ॥

(आक्षेपसाधकभाष्यम्)

इह तर्हि अक्षू इति "अचिश्नुधातुभ्रुवां य्वोः" इत्युवङादेशः प्रसज्येत ॥

(प्रदीपः) अक्षू इति । ननु णुर्धातुषु पठितः । न चास्य तेन सारूप्यम् ॥ नैष दोषः । प्रयोगे नुशब्द एव धातुत्वेन चास्य सारूप्यमस्त्येव । यद्यपि चायं सानुबन्धकस्तथापि धातुष्वननुबन्धकपरिभाषा कैश्चिन्नाश्रीयते । अथ वोपलक्षणार्थमिदं, तेन स्थाणू वेणू इत्युदाहरणम् ॥

(उद्द्योतः) नन्विति । पठितसारूप्यस्यैव संज्ञाप्रयोजकत्वादिति भावः ॥ नैष इति । कार्यार्थत्वात् संज्ञायाः प्रयोगे नुशब्दावस्थायामेव संज्ञाप्रवृत्तिर्न तु ण्वावस्थायां नुशब्दसंज्ञार्थमेव णुपाठ इति प्रयोगस्थे पठितणुत्वारोपेण संज्ञाप्रवृत्त्या तत्स्वरूपेऽतिप्रसञ्जनं युक्तम् ॥ णो न इत्यादौ तु धात्वादेरित्यस्य भाविसंज्ञापरत्वान्न दोष इति भावः ॥ अयं क्रमत्ययः ॥ कैश्चिदिति । भूवादय इत्यत्र नाश्रीयतइत्यर्थः ॥ अथ वेति । अयमभ्युच्चयः । प्रागुक्तरीत्या सामञ्जस्यात् । किं चैवं श्नुग्रहणस्य ज्ञापकत्वपरभाष्यासंगतिः, अक्षू इत्याद्युवङापत्तिस्तूवर्णान्तधात्वन्ताङ्गस्येत्यर्थमभिप्रेत्य बोध्या ॥

(आक्षेपबाधकभाष्यम्)

नैष दोषः । आचार्यप्रवृत्तिर्ज्ञापयति 'न प्रत्ययस्योवङादेशो भवति' इति । यदयं तत्र श्नुग्रहणं करोति ॥

(इष्टानुपपत्तिभाष्यम्)

अस्य तर्हि दिवृशब्दस्याधातुरिति प्रातिपदिकसंज्ञायाः प्रतिषेधः प्रसज्येत । अप्रातिपदिकत्वात्स्वाद्युत्पत्तिर्न स्यात् ॥

(उद्द्योतः) भाष्येऽस्य तर्हि दिवृशब्दस्येति । अव्युत्पन्नप्रातिपदिकस्येत्यर्थः ॥

(अनुपपत्तिबाधकभाष्यम्)

नैष दोषः। आचार्यप्रवृत्तिर्ज्ञापयत्युत्पद्यन्ते दिवृशब्दात्स्वादय इति । यदयं दिवः सावौत्वं शास्ति॥

(अनुपपत्तिसाधकभाष्यम्)

नैतदस्ति ज्ञापकम् । अस्ति ह्यन्यदेतस्य वचने प्रयोजनम् ॥ किम् ? । दिवृशब्दो यः प्रातिपदिकं तदर्थमेतत्स्यात् । अक्षद्यूरिति ॥

(प्रदीपः) अक्षद्यूरिति । अत्र कृदन्तत्वात्प्रातिपदिकत्वम् ॥

(उद्द्योतः) नन्वत्रापि धातुत्वात्कथं प्रातिपदिकत्वमत आह—अत्रेति । कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणादिति भावः ॥

(अनुपपत्तिबाधकभाष्यम्)

न वै अत्रेष्यते ॥

(प्रदीपः) न वै अत्रेष्यत इति । शिष्टप्रयोगाभावात् । तस्माद्दिव औदिति ज्ञापकमेव ॥

(उद्द्योतः) न वै अत्रेतिभाष्यं पुनरुक्तमतो वाक्यभेदेन योजयति—**शिष्टेति** । अत्र शिष्टप्रयोगादेवौत्वाप्रवृत्तौ स्वर्गार्थकदिव्शब्दार्थमेवेदम्, स चेद्धातुत्वादप्रातिपदिकं व्यर्थमेव तदिति ज्ञापकत्वमिति भावः ॥

(अनुपपत्तिसाधकभाष्यम्)

अनिष्टं च प्राप्नोति, इष्टं च न सिध्यति ॥

(प्रदीपः) इतरो ज्ञापकत्वं विघटयति—**अनिष्टं चेति** ॥

(उद्द्योतः) **इतर इति** । अप्रयोगस्य लक्षणैकचक्षुष्कैर्दुर्ज्ञेयतया चारितार्थ्यसंभावनासत्त्वादिति भावः ॥ यद्यपीष्टं न सिध्यति तथाप्यनिष्टप्राप्त्यर्थमेव शास्त्रं स्यात् । तथा च विपरीत एवेष्टानिष्टविभागः स्यादिति भाष्यार्थः ॥

(अनुपपत्तिबाधकभाष्यम्)

एवं तर्हि 'अननुबन्धकग्रहणे न सानुबन्धकस्य' इत्येवमेतस्य न भविष्यति ॥

(प्रदीपः) **एवं तर्हीति** । धातुः सानुबन्धक इति भावः ॥

(उद्द्योतः) ज्ञापकबाधाह—**एवं तर्हीति** ॥

(अनुपपत्तिसाधकभाष्यम्)

एवमप्यननुबन्धको दिव्शब्दो नास्तीति कृत्वा सानुबन्धकस्य ग्रहणं विज्ञास्यते ॥

(प्रदीपः) **एवमपीति** । अधातुरिति प्रातिपदिकसंज्ञानिषेधान्निरनुबन्धकात्सोरसंभवः ॥ उभयसंभवे चास्याः परिभाषाया उपस्थानं नान्यथा ॥

(उद्द्योतः) तत्खण्डनबाधाह—**एवमपीति** ॥ **नास्तीत्यस्य सुपर** इत्यादिस्तदाह—**अधातुरिति** । तदेवं **समानशब्दातिप्रसङ्गः स्थितः** ॥ अत एव * **परिमाणग्रहणं च** * इति चकारस्तदर्थे भगवता न व्याख्यातः ॥

(८०८ आक्षेपान्तरवार्तिकम् ॥ ३ ॥)

॥ * ॥ परिमाणग्रहणं च ॥ * ॥

(भाष्यम्) **परिमाणग्रहणं च कर्तव्यम् । इयानवधिर्धातुसंज्ञो भवतीति वक्तव्यम् ॥ कुतो ह्येतत्—भूशब्दो धातुसंज्ञो भविष्यति, न पुनर्भ्वेधशब्दः—इति ? ॥**

(प्रदीपः) **इयानवधिरिति** । अवधिमानवधिनोपलक्ष्यते विशिष्टावधिपरिच्छिन्नस्य धातुसंज्ञा विधेयेत्यर्थः ॥ **भ्वेधश्च इति** । ततश्च भ्वेधशब्दाड्डडादिप्रसङ्गः । न चार्थपाठः परिच्छेदकः । तस्यापाणिनीयत्वात् । अभियुक्तैरुपलक्षणतयोपात्तत्वादनेकार्थत्वदर्शनादर्थस्य नियामकत्वाभावात् ॥

(उद्द्योतः) अवधेः संज्ञायामूकारादेरेव सा स्यान्न भू इत्यादेरत आह—**अवधिमानिति** । इदं चेयत्पदेन भाष्ये ध्वनितमिति भावः ॥ **अभियुक्तैरिति** । भीमसेनेनेत्यैतिह्यम् ॥ तत्रैव हेतुमाह—**अनेकार्थत्वेति** । अर्थनिर्देशस्य व्यभिचरितत्वेनाप्रयोजकत्वाद्व्यवच्छेदकत्वाभावेन परिमाणग्रहणमपि कार्यमिति भावः ॥

(न्यासान्तरेण समाधानसंभावनाभाष्यम्)

यदि पुनः—

(८०९ न्यासान्तरवार्तिकम् ॥ ४ ॥)

॥ * ॥ क्रियावचनो धातुः ॥ * ॥

(भाष्यम्) **इत्येतल्लक्षणं क्रियेत ॥**

(प्रदीपः) **क्रियावचन इति** । एवं सति समानशब्दानां प्रतिषेधो न वक्तव्यः । नापि परिमाणग्रहणम् । **नहि** भ्वेधशब्दसमुदायः क्रियावाची ॥

(उद्द्योतः) क्रियेतेति लिङ्बोधितेऽस्य लक्षणस्य संभावनीयत्वे हेतुमाह—**एवमिति** । **नहीति** । अवयवानां वाचकत्वेपि दशदाडिमादिवत्समुदायोऽनर्थक इति भावः ॥

(प्रश्नोत्तरभाष्यम्)

का पुनः क्रिया ? ॥ ईहा ॥ का पुनरीहा ? ॥ चेष्टा ॥ का पुनश्चेष्टा ? ॥ व्यापारः ॥

(प्रदीपः) **का पुनरिति** । द्रव्यव्यतिरेकेण तस्याः सत्तामसंभावयतः प्रश्नः ॥ **ईहेति** । ईहाचेष्टाशब्दयोरन्यत्र व्यापारविशेषवचनत्वेपि इह व्यापारमात्रवचनत्वं बोद्धव्यम् ॥ कस्यचित्केनचिच्छब्देन सोर्थः प्रसिद्ध इत्यनेकपर्यायोपादानम् ॥

(उद्द्योतः) शब्दानुशासनप्रवृत्तानामर्थविवेचने का प्रसक्तिरत आह—**द्रव्येति** ॥ **असंभावयत इति** । अप्रत्यक्षत्वादिति भावः ॥ एवं च प्रकृतलक्षणेनापि द्रव्यवाचिनां धातुत्वानिवृत्तेः समानशब्दातिप्रसङ्गस्तदवस्थ इति भावः ॥ **अन्यत्रेति** । मानसव्यापार इच्छारूपेहा । **इच्छा काङ्क्षा स्पृहेहा तृडिति** कोशात् ॥ कायपरिस्पन्दश्चेष्टा ॥ **इहेति** । **समानमीहमानानामिति** भाष्यप्रयोगादीह चेष्टायामित्यर्थनिर्देशाच्चेति भावः ॥ नन्वेकपर्यायेणार्थस्य व्याख्यानसंभवात्पर्यायान्तरोपादानमनर्थकमत आह—**कस्यचिदिति** ॥

(उपहासाक्षेपभाष्यम्)

सर्वथा भवाञ्छब्दैरेव शब्दानाचष्टे, न किंचिदर्थजातं निदर्शयत्येवंजातीयका क्रियेति ॥

(प्रदीपः) **सर्वथेति** । यावद्द्रव्यव्यतिरेकेण क्रियासद्भावे प्रमाणं प्रोक्तं तावत्पर्यायोपादानमात्रेण तस्याः स्वरूपं न निश्चीयत इत्यर्थः ॥ **अर्थजातमिति** । अर्थस्वरूपमित्यर्थः ॥

(उद्द्योतः) **सर्वथे**त्यादिभाष्यमुपहासपरं स किं शब्दैर्व्याकरोषीति वा, उत शब्दान्व्याकरोषीति । नाद्यः । शब्दैरेव यतो व्याख्यानं नाक्षिनिकोचादिभिः । नान्त्यः—प्रयुक्तशब्दस्याप्रसिद्धत्वे व्याख्येयत्वादत आह—**यावदिति** ॥ क्रियापदार्थप्रश्ने इदं युक्तं, न तु क्रियापदार्थो नातिरिक्तो द्रव्यादिति प्रश्ने । तत्र हि द्रव्यव्यतिरेक एव साधनीय इत्युपहास इति भावद्रव्यव्यतिरेकः ॥ शब्दैरेव शब्दान् व्याकरोतीति भाष्याक्षरार्थः ॥ समूहार्थकजातशब्दस्य प्रकृतेनन्वयादाह—**अर्थेति** । अत्रेदं तत्त्वम् ॥

कारकं न क्रिया तस्यां कारकानन्वयापत्तेः, कारकाणां मिथः संबन्धायोग्यत्वात् । तस्माद् द्रव्यातिरिक्तक्रियासिद्धेः सर्वथत्युपहासः कारकातिरिक्तक्रिया प्रत्यक्षेण नोपलभ्यत इत्येवंपरो वाच्यः । स चेष्ट एवेति गूढाभिसंधिप्रत्युपहासपरं क्रियानामेत्यादिभाष्यम् ॥

(समाधानभाष्यम्)

क्रिया नामेयमत्यन्तापरिदृष्टाऽशक्या पिण्डीभूता निदर्शयितुम् । यथा गर्भो निर्लुठितः । साऽसावनुमानगम्या ॥

(प्रदीपः) **अशक्येति** । आख्यातपदवाच्या पूर्वापरीभूतावयवा साध्यमानावस्था भूतभविष्यद्वर्तमानसदसदनेकावयवसमूहरूपा सद्वस्तुविषयेन्द्रियग्राह्या न भवतीत्यर्थः ॥ **पिण्डीभूतेति** । यथा परमाणवः पिण्डीभूता उपलभ्यन्ते न केवलाः, एवं पिण्डीभावाभावात् क्रिया न प्रत्यक्षेत्यर्थः ॥ **गर्भो निर्लुठित इति** । यथा कुक्षिस्थो गर्भोऽप्रत्यक्षस्तथा क्रियेत्यर्थः । अथवा यथा निर्लुठितो निर्गतः कुक्षेर्गर्भः प्रत्यक्षो नैवं क्रियेति वैधर्म्येण दृष्टान्तः ॥ **सासाविति** । या पूर्वमुक्ता सासावनुमानेन प्रतीयत इत्यर्थः ॥

(उद्द्योतः) **अत्यन्तापरदृष्टेति** । परेण प्रमाणेन प्रत्यक्षेणात्यन्तमवयवशः समूहरूपेण चादृष्टेत्यर्थः ॥ तत्र निदर्शनस्याशक्यत्वे हेतुमाह—**आख्यातेति** । तत्राप्रत्यक्षत्वे हेतुरनेकावयवरूपत्वं, तच्च घटादिषु व्यभिचरितमतः **सदसदिति** । तदुपपादकं **भूतेत्यादि** ॥ समूहव्यवहारो बुद्धिकृतो विकल्परूप एव, न वास्तव इति बोध्यम् ॥ नन्वतीतप्रयोगे सर्वेषामतीतत्वाद्भविष्यति सर्वेषां भावित्वाच्च कथं सर्वत्र त्रैरूप्यमत आह—**पूर्वापरीभूतेति** ॥ तत्त्वे बीजमाह—**साध्यमानेति** । वर्तमानविषयेपि तत्त्वमेवमुपपाद्यम् । तथाहि । **वर्तमानत्वं** प्रारब्धापरिसमाप्तत्वम् । न ह्येकत्र क्षणे तत्त्वं संभवति, तस्मादारब्धत्वमतीतक्षणमादाय, असमाप्तत्वं तु भविष्यत्क्षणमादायेत्येव समर्थनीयम्, क्षणा एव च क्रियाधारा इति । न च तत्तत्कालसंबन्ध एव **वर्तमानत्वमिति** वाच्यम् । एवं हि परं प्रति पश्य मृगो धावतीति शब्दप्रयोगानुपपत्तेः । नहि स्वज्ञानप्रभृतिपरज्ञानपर्यन्तमेकः क्षणोस्ति समूहरूपत्वे त्ववयवान्तरावच्छेदेन स्वानुभूतां वर्तमानतामवयवान्तरावच्छेदेन परं बोधयितुं तदुपपत्तेः । बिलाद्बिलं प्रविशति सर्पे किंचिदवयवावच्छेदेन सर्पमनुभवतोवयवान्तरावच्छेदेन तं दर्शयितुं सर्प पश्येति प्रयोगवत् ॥ **सद्वस्त्विति** । सद्वस्तूनि विषयाणि येषामिन्द्रियाणां तद्ग्राह्या नेत्यर्थः ॥ ननु यदि पिण्डीभूता क्रिया कुतो निदर्शयितुं न शक्येत्यत आह—**यथेति** ॥ **पिण्डीभूता इति** । कार्यात्मना श्रिता इत्यर्थः । अनेन दृष्टान्तेन परमाणुवदवयवक्रियाणामप्यप्रत्यक्षत्वं सूचितम् ॥ **कुक्षिस्थ इति** । आद्ये अनिर्लुठित इति छेदः । द्वितीये निर्लुठित इति छेदो निष्क्रान्त इति च तदर्थ इति भेदः ॥ अत्यन्तापरदृष्टत्वेनावयवरूपेणाप्यप्रत्यक्षत्वं तदवयवानां क्षणरूपत्वात् । पश्य धावतीति तदनुमापकफलपरमेव । एतेन क्रियानुमेयैवेत्युक्तं भवति । **वर्तमाने** लडितिसूत्रस्थभाष्यस्वरसोप्येवमेव ॥ **या पूर्वमिति** । अदःशब्द इदमर्थ इति न पौनरुक्त्यमिति भावः ॥ तच्छब्दाव्यवहितोत्तरवर्त्यदश्शब्दः प्रसिद्ध्यर्थक इत्यन्ये ॥

(आक्षेपभाष्यम्)

कोसावनुमानः ? ।

(प्रदीपः) **कोसाविति** । यो भावे ल्युट् स नपुंसकः । अन्यत्र त्वभिधेयवशादनियतलिङ्गः । अथ वा मन्यतेर्घञ्यनुमान इति रूपम् ॥

(उद्द्योतः) ननु ल्युडन्तत्वे नपुंसकत्वं स्यादत आह—**यो भाव इति** । तथा च करणे ल्युडिति भावः ॥ **अथ वेति** । प्रौढ्या ॥

(समाधानभाष्यम्)

इह सर्वेषु साधनेषु संनिहितेषु कदाचित्पचतीत्येतद्भवति कदाचिन्न भवति । यस्मिन्संनिहिते पचतीत्येतद्भवति सा नूनं क्रिया ॥ अथ वा यया देवदत्त इह भूत्वा पाटलिपुत्रे भवति सा नूनं क्रिया ॥

(प्रदीपः) **यस्मिन्संनिहिते इति** । यस्मिन्वस्तुनि संनिहिते सति पचतीत्येतत्प्रयुज्यते नासति सा क्रिया । क्वचित्तु **यस्मिन् साधने संनिहिते** इति पाठः ॥ तत्रायमर्थः—यस्मिन्संनिहिते सति पचतीत्येतत्साधनविषये भवतीति ॥ स्यादेतत् । मृगतृष्णिकाविषयजलज्ञानवत्पचतीत्येतदसत्यविषयमेव ज्ञानमित्याशङ्क्याह—**अथ वेति** । देशान्तरप्राप्तिलक्षणेन कार्येणाऽबाधितेन क्रियाख्यं कारणमनुमीयत इत्यर्थः ॥ ननु प्रत्यक्षाप्रवृत्तौ संबन्धग्रहणाभावात् कथं क्रियाविषयमनुमानं प्रवर्तते । नैष दोषः । धातुवाच्यस्य समूहस्य युगपदसंनिधानादप्रत्यक्षत्वेप्येकैकस्य तु क्षणस्य प्रत्यक्षत्वे बुद्ध्या तान्क्षणान्संकलय्य पचतीति प्रयुज्यते । यदाप्येकस्मिन्क्षणे पचतीति प्रयोगस्तदा तत्र समूहरूपारोपणम् । शब्दशक्तिस्वभावाच्चैकः क्षणो नैव धातुवाच्यः ॥

(उद्द्योतः) नन्वनुमापकलिङ्गपक्षे कारकसमवधानकालिकपचत्यादिव्यवहारव्यतिरेकप्रयोजकव्यतिरेकप्रतियोगित्वरूपं लक्षणमुक्तं न तु लिङ्गमित्यनस्तदपि सूचितमित्याह—**यस्मिन्निति** ॥ **कारकभेदसाधने** लक्षणस्यैव लिङ्गत्वेपि लिङ्गान्तरसूचनमिदं 'विमतं कारकेभ्यो भिद्यते बाधकाभावे कारकसत्ताकालेऽव्यवह्रियमाणत्वाद्बाधकाभावे यद्यत्काले न व्यवह्रियते तत्ततो भिद्यते' इति प्रयोगः ॥ ननु यस्मिन् साधन इति पाठे यत्तद्भ्यां कारकस्यैव क्रियात्वं प्रतीयते तच्च विरुद्धमत आह—**यस्मिन्निति** ॥ **मृगेति** । ज्ञान न वस्तुसत्तासाधकमसतोपि शशशृङ्गादेः शाब्दज्ञानदर्शनादिति भावः ॥ **देशान्तरेति** । संयोगजभिन्नः संयोगः क्रियाजन्यः कारकाजन्यत्वे सति जन्यत्वादिति प्रयोगः । संयोगस्य क्रियाफलमात्रोपलक्षकत्वं बोध्यम् । फलानुमेया क्रियेति तात्पर्यम् ॥ एतेन पचत्यादिष्वस्य हेतोरसंभव इत्यपास्तम् ॥ **संबन्धग्रहणेति** । फलव्यापारयोर्जन्यजनकभावग्रहे सति हि कार्येण कारणानुमानं स्यात्स एव तु दुर्घटोऽ-

प्रत्यक्षत्वादिति भावः ॥ **एकैकस्येति ।** अधिश्रयणादेरित्यर्थः ॥ **प्रत्यक्षत्वेनेति ।** पश्य मृगो धावतीतिप्रत्ययादित्यर्थः ॥ **बुद्ध्या संकल्प्येति ।** स्मृत्या विषयीकृत्येत्यर्थः । उपस्थिते च संबन्धग्रहो न प्रत्येक्षेणोपस्थित एवेति नियम इति भावः ॥ एवं संबन्धग्रहे सति कार्येण तामनुमाय पचतीति प्रयुज्यत इति तात्पर्यम् ॥ इदं च योगिप्रयोगविषयं तेषामेवावयवक्रियाप्रत्यक्षात् ॥ अस्माकं तद्व्यवहारपरम्परया सर्वथा विकल्पात्मक एव प्रयोगः क्रियापदानामिति बोध्यम् ॥ एतच्च **वर्तमाने लडिति** सूत्रे भाष्ये ध्वनितम् ॥ ननु समूहस्याप्रत्यक्षत्वेप्येकक्षणस्य प्रत्यक्षत्वसंभवात् क्रियामात्रे आनुमानिकत्वकथनमयुक्तमित्याशङ्क्य परिहरति—**यद्यपीति ।** तथा च तस्य व्यवहाराविषयत्वाद्व्यवहारविषया सर्वानुमेयैवेति भाष्यतात्पर्यमिति भावः ॥ ननु तदारोपेपि वस्तुत एकस्यैव लक्षणस्य क्रियात्वेन तत्र प्रत्यक्षत्वं व्यवहारविषयत्वं च दुर्वारमत आह—**शब्दशक्तीति ॥ एकः क्षण इति ।** अनारोपितसमूहरूप एकः क्षण इत्यर्थः ॥ परे त्वधिश्रयणादिरपि नैकक्षणात्मकस्तस्यापि हस्तप्रसारणपात्रादानचुल्लीसंयोजनादयोवयवाः सन्त्येवेति सोपि समूहरूप एव । यस्तु तेषामप्यवयवः परमाणुप्रख्यः स तु शब्दशक्तिस्वभावान्नैव वाच्यो नापि प्रत्यक्षः । अनुमानं त्वेवम् उत्तरदेशसंयोगादिफलं कारणजन्यं कार्यत्वादिति ॥ तच्च कारणं प्रसिद्धातिरेकि, इतरबाधबलात् क्रियारूपमेव सिध्यतीति भाष्यतात्पर्यमित्याहुः ॥

(आक्षेपभाष्यम्)

कथं पुनर्ज्ञायते क्रियावचनाः पचादय इति ? ॥

(समाधानभाष्यम्)

यदेतेषां करोतिना सामानाधिकरण्यम् । 'किं करोति ? पचति' 'किं करिष्यति ? पक्ष्यति' 'किमकार्षीद् ? अपाक्षीद्' इति ॥

(प्रदीपः) **किं करोति पचतीति ।** सामान्यविशेषभावेन सामानाधिकरण्यात् क्रियाविशेषवचनाः पचादयः प्रतीयन्त इत्यर्थः । यदा तु किं करोतीति पृष्टे न करोत्यास्त एव केवलमिति प्रतिवचनं तदा व्यापारमात्रस्यावश्यंभावित्वाद्व्यापारविशेषविषयः प्रश्नः प्रतिवचनं तु विशेषनिराकरणेनेति बोद्धव्यम् ॥

(उद्द्योतः) नन्वेकार्थबोधकत्वं सामानाधिकरण्यं न प्रकृतेऽत आह—**सामान्येति ।** तथा च धातुलक्षणे क्रियातद्व्याप्यान्यतरवचनत्वं विवक्षितमिति न दोषः । यद्यपि करोतिर्गन्धनावक्षेपणादिष्वपि वर्त्तते तथापि कारकव्यापार एव तदर्थः प्रसिद्ध इति भावः ॥ अन्य यो व्यापारसामान्यवाची तद्विशेषाः पचादयः किं करोतीत्यस्य च यत्करोति तत्किमिति व्यापारविशेषविषयप्रश्नोर्थः । एवं च यन्निष्ठतया प्रश्नविषयक्रियायाः करोतिशब्दवाच्यायाः प्रतीतिस्तन्निष्ठतयैवोत्तरभूतपचतिशब्दवाच्यक्रियायाः प्रतीतिरिति तयोः सामानाधिकरण्यं, तत्र क्रियाप्रश्नजनकजिज्ञासायास्तद्विषयोत्तरेणैव निरासादेषां क्रियावाचित्वमिति भावः ॥ नन्वेवं पनसो वृक्ष इतिवत् पचति करोतीति सहाप्रयोगापत्तिरिति चेन्न । केवलस्य धातोः प्रयोगाभावेन तिङ्प्रयोगे तदर्थपौनरुक्त्यभीत्या तथा प्रयोगाभावाद् यत्र तु नेदृशं बाधकं तत्रैवांचकारेत्यादि प्रयुज्यत एवेति दिक् ॥ **यदास्त्विति ।** आस्तेरपि क्रियाविशेषत्वम् । अत एव गमनासनशयनसंशयात्प्रश्ने आस्ते इति प्रतिवचनमिति बोध्यम् ॥

(भाष्यम्) तत्र—

(८१० आक्षेपवार्तिकम् ॥ ५ ॥)

॥ * ॥ क्रियावचने उपसर्गप्रत्ययप्रतिषेधः ॥ * ॥

(भाष्यम्) **क्रियावचने धातावुपसर्गप्रत्यययोः प्रतिषेधो वक्तव्यः । पचति प्रपचति ॥**

(उद्द्योतः) पाठनिरपेक्षमिदं लक्षणमिति शङ्कते—भाष्ये—**तत्रेति ।**

(भाष्यम्) **किं पुनः कारणं प्राप्नोति ? ।**

(८११ आक्षेपसाधकवार्तिकम् ॥ ६ ॥)

॥ * ॥ संघातेनार्थगतेः ॥ * ॥

(भाष्यम्) **संघातेन ह्यर्थो गम्यते सप्रकृतिकेन सप्रत्ययकेन सोपसर्गेण च ॥**

(प्रदीपः) **संघातेनेति ।** संघातस्यैव प्रयोगादर्थवत्त्वम् । केवलानां तु धातूनामप्रयोगादानर्थक्यम् ॥

(उद्द्योतः) ननूपसर्गस्य धात्वर्थविशेषकत्वात्प्रत्ययस्य कर्त्रर्थकत्वाच्च प्राप्त्यभावेन प्रतिषेधानुपपत्तिरत आह भाष्ये—**संघातेनार्थगतेरिति ।** बोद्धेति शेषः ॥ तद्व्याचष्टे—**संघातस्येति ।** उपसर्गप्रत्यययोरित्यस्य तद्विशिष्टयोरित्यर्थ इति भावः ॥ **अर्थवत्त्वमिति ।** अन्वयव्यतिरेकाभ्यामिति भावः ॥

(८१२ आक्षेपान्तरवार्तिकम् ॥ ७ ॥)

॥ * ॥ अस्तिभवतिविद्यतीनां च धातुत्वम् ॥ * ॥

(भाष्यम्) **अस्तिभवतिविद्यतीनां च धातुसंज्ञा वक्तव्या ॥ यथा हि भवता करोतिना पचादीनां सामानाधिकरण्यं दर्शितम्, न तथास्त्यादीनां निदर्श्यते । नहि भवति—किं करोति ?, अस्तीति ॥**

(उद्द्योतः) भाष्ये यथा हीत्यादि । प्रागुक्तकरोतिसामानाधिकरण्यरूपक्रियावाचित्वचिह्नाभावात्तदभाव इति भावः ॥

(८१३ प्रथमाक्षेप (८१०) समाधानवार्तिकम् ॥ ८ ॥)

॥ * ॥ प्रत्ययार्थस्याऽव्यतिरेकात्प्रकृत्यन्तरेषु ॥ * ॥

(भाष्यम्) **प्रत्ययार्थस्याव्यतिरेकात्प्रकृत्यन्तरेषु मन्यामहे धातुरेव क्रियामाहेति । पचति पठति । प्रकृत्यर्थोऽन्यश्चान्यश्च । प्रत्ययार्थः स एव ॥**

(उद्द्योतः) अतिव्याप्तिं निरकरोति—भाष्ये—**प्रत्ययार्थस्येति ॥ अव्यतिरेकः** अभेदः ॥ **प्रकृत्यन्तरेषु** भिन्नार्थकेषु ॥

(८१४ समाधानसाधकवार्तिकम् ॥ ९ ॥)

॥*॥ धातोश्चार्थाभेदात्प्रत्ययान्तरेषु ॥*॥

(भाष्यम्) धातोश्चार्थाभेदात्प्रत्ययान्तरेषु मन्यामहे धातुरेव क्रियामाहेति । पक्तिः पचनं पाक इति । प्रत्ययार्थोन्यश्चान्यश्च भवति । प्रकृत्यर्थः स एव ॥

(उद्द्योतः) प्रत्ययस्याप्यावापोद्धारं दर्शयति—धातोश्चेति ॥ अन्यश्चेति । लिङ्गभेदादित्यर्थः ॥

(भाष्यम्) कथं पुनर्ज्ञायते—अयं प्रकृत्यर्थः, अयं प्रत्ययार्थ इति ॥

(८१५ समाधानसाधकवार्तिकम् ॥ १० ॥)

॥ * ॥ अन्वयव्यतिरेकाभ्याम् ॥ * ॥

(भाष्यम्) अन्वयाच्च व्यतिरेकाच्च । कोसावन्वयो व्यतिरेको वा ? । इह पचतीत्युक्ते कश्चिच्छब्दः श्रूयते पच्छब्दश्चकारान्तः, अतिशब्दश्च प्रत्ययः । अर्थोपि कश्चिद्गम्यते विक्लित्तिः कर्तृत्वमेकत्वं च ॥ पठतीत्युक्ते कश्चिच्छब्दो हीयते कश्चिदुपजायते, कश्चिदन्वयी । पच्छब्दो हीयते, पठ्शब्द उपजायते अतिशब्दोन्वयी । अर्थोपि कश्चिद्धीयते कश्चिदुपजायते कश्चिदन्वयी । विक्लित्तिर्हीयते, पठिक्रियोपजायते, कर्तृत्वं चैकत्वं चान्वयी । ते मन्यामहे—यः शब्दो हीयते तस्यासावर्थः योर्थो हीयते, यः शब्द उपजायते तस्यासावर्थः योर्थ उपजायते, यः शब्दोन्वयी तस्यासावर्थः योर्थोन्वयी ॥

(प्रदीपः) अतिशब्दश्चेति । यद्यप्ययं प्रत्ययसमुदायः, तथापि प्रकृतिभागावबोधपरत्वात्प्रत्ययभागपर्यालोचनेऽनादरादेवमुक्तम् ॥ अथ वा पूर्वाचार्यैः कैश्चिदतिः प्रत्ययत्वेन कल्पित इति तदपेक्षयैतदुक्तम् ॥

(उद्द्योतः) अन्वयव्यतिरेकाभ्यामिति वार्तिकेन धातोरेव क्रियावाचित्वं काल्पनिकमिति प्रतिपाद्यते । इत उत्तरभाष्यं न चेत्सामान्यशब्दा स्युरित्यन्तमर्थवत्सूत्रे व्याख्यातम् । तत एवावधार्यम् ॥

(समाधानसाधकभाष्यम्)

विषम उपन्यासः । बहवो हि शब्दा एकार्था भवन्ति । तद्यथा—इन्द्रः शक्रः पुरुहूतः पुरंदरः । कन्दुः कोष्ठः कुसूल इति ॥ एकश्च शब्दो बह्वर्थः । तद्यथा—अक्षाः पादा माषा इति ॥

अतः किम् ॥ न साधीयोऽर्थवत्ता सिद्धा भवति । नापि ब्रूमोऽर्थवत्ता न सिध्यतीति । वर्णिता ह्यर्थवत्ताऽन्वयव्यतिरेकाभ्यामेव ॥ तत्र कुत एतद्यं प्रकृत्यर्थोयं प्रत्ययार्थ इति न पुनः प्रकृतिरेवोभावर्थौ ब्रूयात्प्रत्यय एव वा ? ॥

(प्रदीपः) किं न साधीय इति । यदा प्रकृतिरेव क्रियां साधनं चाह तदा सिद्धमेव प्रकृतेः क्रियावाचित्वम् । प्रत्यय एवेति । ततश्च प्रकृतेर्न स्यात्क्रियावाचित्वम् ॥

(समाधानसाधकभाष्यम्)

सामान्यशब्दा एत एवं स्युः । सामान्यशब्दाश्च नान्तरेण प्रकरणं विशेषणं वा विशेषेष्ववतिष्ठन्ते । यतस्तु खलु नियोगतः पचतीत्युक्ते स्वभावतः कस्मिंश्चिद्विशेषे पच्शब्दो वर्ततेऽतो मन्यामहे—नेमे सामान्यशब्दा इति । न चेत्सामान्यशब्दाः प्रकृतिः प्रकृत्यर्थे वर्तते प्रत्ययः प्रत्ययार्थे ॥

(उद्द्योतः) प्रत्ययः प्रत्ययार्थे इति । प्रत्ययोऽत्वर्थे इत्यर्थः । प्रातिपदिकविषये पाचकस्य प्रातिपदिकार्थतयाऽर्थवत्त्वप्रस्य भाष्यस्यैवमेव व्याख्येयत्वात् ॥

(८१६ प्रथमाक्षेपसमाधानवार्तिकम् ॥ ११ ॥)

॥ * ॥ क्रियाविशेषक उपसर्गः ॥ * ॥

(भाष्यम्) पचतीति क्रिया गम्यते, तां प्रो विशिनष्टि ॥

(उद्द्योतः) तदेवं सप्रत्ययकेऽतिव्याप्तिं निरस्य सोपसर्गे तां निराकरोति—भाष्ये—क्रियाविशेषक उपसर्ग इति । यथान्वयव्यतिरेकाभ्यां प्रत्ययोऽर्थबोधकस्तथा ताभ्यामेव क्रियाविशेषद्योतक उपसर्गः, क्रियावाची धातुरेवेति भावः ॥ प्रोवीति । पचेरुत्कृष्टक्रियापरत्वं द्योतयतीत्यर्थः ॥

(आक्षेपभाष्यम्)

यद्यपि तावदत्रैतच्छक्यते वक्तुं यत्र धातुरुपसर्गं व्यभिचरति ॥ यत्र न खलु तं व्यभिचरति तत्र कथम् अध्येति अधीते इति ? ॥

(उद्द्योतः) यद्यपि तावदिति । उपसर्गाव्यभिचारिधातुस्थले तत्त्वासम्भवादिति भावः ॥

(समाधानभाष्यम्)

यद्यप्यत्र धातुरुपसर्गं न व्यभिचरति उपसर्गस्तु धातुं व्यभिचरति । ते मन्यामहे—य एवास्याधेरन्यत्रार्थः, स इहापीति ॥

कः पुनरन्यत्राधेरर्थः ।

अधिरुपरिभावे वर्तते ॥

(प्रदीपः) अधिरुपरिभाव इति । ततश्चाधीत इत्यस्य

विशिष्टार्थयुक्तानां शब्दानां पठनं विधिपूर्वकं वा करोतीत्यर्थः । अध्येतीत्यत्र विशिष्टं स्मरणरूपं ज्ञानं धात्वर्थः ॥

(उद्द्योतः) यद्यप्यत्रेति । धातोरुपसर्गाव्यभिचारेऽप्युपसर्गस्य धातुव्यभिचारादन्यत्र द्योत्यत्वेन निश्चितोर्थ एवेहाप्यधेरिति भावः ॥ नन्विदमयुक्तमधीते इत्यादावुपरिभावाप्रतीतेरत आह—ततश्चेति । उत्कर्षलक्षण उपरिभावोधेरर्थः । स च विशिष्टार्थयुक्तत्वरूपो विधिपूर्वकत्वरूपो वेति भावः ॥ केचित्त्ववगमपर्यन्तत्वरूप उत्कर्षोधेरर्थ इत्याहुः ॥ विशिष्टस्मरणमिति । निरन्तरत्वादिकं तत्रोत्कर्षः ॥

(आक्षेपभाष्यम्)

इह तर्हि व्यक्तमर्थान्तरं गम्यते—तिष्ठति प्रतिष्ठते इति । तिष्ठतीति व्रजिक्रियायाः निवृत्तिः । प्रतिष्ठत इति व्रजिक्रिया गम्यते । ते मन्यामहे उपसर्गकृतमेतद्, येनात्र व्रजिक्रिया गम्यत इति ॥

(उद्द्योतः) भाष्ये—इह तर्हि व्यक्तमिति । तत्र व्रजिक्रियाया उपसर्गमात्रार्थत्वे तिष्ठतेर्धातुत्वानापत्तिः । तिष्ठतिमात्रस्य तु नार्थस्तस्य तन्निवृत्त्यर्थकत्वाद् ॥ विशिष्टस्य तदर्थकत्वे तु तस्यैव धातुत्वापत्तिरिति भावः ॥

(समाधानभाष्यम्)

प्रोयं दृष्टापचारः आदिकर्मणि वर्तते ॥ न चेदं नास्ति—बह्वर्था अपि धातवो भवन्तीति । तद्यथा—वपिः प्रकिरणे दृष्टः, छेदने चापि वर्तते—केशश्मश्रु वपतीति । ईडिः स्तुतिचोदनायाच्ञासु दृष्टः, प्रेरणे चापि वर्तते—'अग्निर्वा इतो वृष्टिमीट्टे मरुतोमुतश्च्यावयन्ति' इति । करोतिरभूतप्रादुर्भावे दृष्टः, निर्मलीकरणे चापि वर्तते—'पृष्ठं कुरु' 'पादौ कुरु' उन्मृदानेति गम्यते । निक्षेपणे चापि वर्तते 'कटे कुरु' 'घटे कुरु' 'अश्मानमितः कुरु' स्थापयेति गम्यते । एवमिहापि तिष्ठतिरेव व्रजिक्रियामाह तिष्ठतिरेव व्रजिक्रियायाः निवृत्तिम् ॥

(प्रदीपः) प्रोयमिति । अन्यत्रापि प्रयोगात् । ततश्चान्यत्रास्य योर्थो द्योत्यः स एवेहापीत्यनुमीयते । अनेकार्थत्वाद्धातूनां तिष्ठतिरेव गतिवाचीति निर्णयः ॥

(उद्द्योतः) समाधत्ते- [प्रो]यमिति । नन्वेवमपि गतिनिवृत्तिवाचिनस्तिष्ठतेः कथं गतिवाचित्वमत आह—अनेकार्थत्वादिति । धातोः कचिदवश्यकल्प्यनानार्थत्वेनैव प्रकृतार्थनिर्वाहे प्रशब्दस्यार्थकल्पने मानाभाव इति भावः ॥ लोकेपि प्रथमगमनकर्तर्येव प्रतिष्ठत इति प्रयुज्यत इति तात्पर्यम् । तदाह—भाष्ये न चेदं नास्तीति ॥ प्रकिरणे इति । मापान्वपतीत्यादौ । वृष्टिमीट्टे इति । प्रेरयतीत्यर्थः ॥

(आक्षेपभाष्यम्)

अयं तर्हि दोषः—* अस्तिभवतिविद्यतीनां धातुत्वम् * इति ॥

(न्यासान्तरेण समाधानसंभावनाभाष्यम्)

यदि पुनः—

(८१७ न्यासान्तरवार्तिकम् ॥ १२ ॥)

॥ * ॥ भाववचनो धातुः ॥ * ॥

(भाष्यम्) **इत्येतल्लक्षणं क्रियेत ॥**

(प्रदीपः) भाववचन इति । भावशब्दः क्रियामात्रवाची । यथा यस्य च भावेनेति 'भावे घञ्' इति च । तेन पचादीनामपि धातुसंज्ञा सिध्यति, अस्तिभवतिविद्यतीनामपि भावरूपार्थाभिधायित्वात् ॥

(उद्द्योतः) ननु भाववचन इतिन्यासे पचादिष्वव्याप्तिरत आह—क्रियामात्रेति । धात्वर्थमात्रेत्यर्थः ॥ मात्रपदं कार्त्स्न्ये ॥ नन्वेवमप्यस्त्यादिष्वव्याप्तिरत आह—अस्तिभवतीत्यादि । तस्मिन् सत्यागतः, भवनं भाव इत्यादिप्रयोगादस्त्यादिक्रियापि भावपदेन गृह्यत इति भावः ॥ नन्वस्त्याद्यर्थस्यापि क्रियात्वे किमपराद्धं पूर्वलक्षणेनेत्यत आह—भावरूपेति । क्रियाशब्दः सपरिस्पन्दसाधनसाध्यार्थे रूढो भावशब्दश्च सपरिस्पन्दापरिस्पन्दान्यतरसाधनसाध्य इति भावः ॥

(संभावितसमाधान आक्षेपभाष्यम्)

कथं पुनर्ज्ञायते—भाववचनाः पचादय इति ? ॥

(उद्द्योतः) इतरो भवत्यर्थोस्य भावशब्देन विवक्षित इत्याशयेन पृच्छति—भाष्ये—कथं पुनरिति ॥

(समाधानभाष्यम्)

यदेषां भवतिना सामानाधिकरण्यम्—भवति पचति, भवति पक्ष्यति, भवति अपाक्षीदिति ॥

(प्रदीपः) भवति पचतीति । आत्मभरणवचनो भवतिः । तच्चात्मभरणं विरुद्धैकार्थसमवायैः पाचकत्वादिभिरविरुद्धैकार्थसमवायम् । यथा शुक्लं रूपमिति शुक्ले गुणे शुक्लत्वं रूपत्वं चास्तीति शुक्लादयो रूपवचनाः एवं पचादयो भाववचना इत्यर्थः ॥

(उद्द्योतः) ननु भवतिपचत्योर्नैकार्थबोधकत्वरूपं सामानाधिकरण्यं, भावः सत्ता विक्लित्त्यनुकूलव्यापारश्च पाक इति तयोरत्यन्तवैलक्षण्यादत आह—आत्मभरणेति । आत्मभरणं चाषष्ठाद्भावविकारादनुस्यूतं सदिति प्रत्ययवेद्यं रूपम्, तच्च केवलान्वयित्वात्पदार्थमात्रसमानाधिकरणम् । एवं चाश्रये पचिक्रियाबोधे तत्समानाधिकरणात्मभरणस्यापि तत्र सत्त्वेन तद्वाचकत्वं पचादीनाम्, यथा शुक्ले गुणे रूपत्वसत्तामात्रेण रूपवचनत्वं शुक्लादीनाम् । तदुक्तम् पाचकत्वादिभिरिति । आदिना गन्तृत्वादि । पाकत्वादिभिरिति पाठान्तरम् । अत्रादिना गमनत्वादि ॥ विरुद्धेति । परस्परमित्यादिः । एवंच पचति भवतीत्यादेर्यत्कर्तृका पचिक्रिया तत्कर्तृका सत्तेति बोधः । एवं च भवत्यर्थपचत्यर्थयोरेकाधिकरणवृत्तित्वमेव भवतिपचत्योः सामानाधिकरण्यमिति भावः ॥

(आक्षेपभाष्यम्)

कः पुनर्भावः ? ॥

(प्रदीपः) **कः पुनरिति** । यदि क्रियैव भावस्तदा पक्षान्तरोपादानमनर्थकमथान्यस्तदाऽव्याप्तिरिति प्रश्नः ॥

(उद्द्योतः) ननूक्तेन सामानाधिकरण्येन भावपदार्थस्याप्युक्तप्रायत्वात्कः पुनरिति प्रश्नोनुपपन्नोऽत आह—**यदीति** ॥

(समाधानभाष्यम्)

भवतेः स्वपदार्थो भवनं भाव इति ॥

(प्रदीपः) **स्वपदार्थ इति** । स्वग्रहणमुपचरितार्थनिवृत्त्यर्थं, गौणोपि पदार्थो भवति न तु स्वो व्यभिचारात् । पदग्रहणं प्रकरणाद्यनपेक्षत्वप्रतिपादनार्थम् । भवनं भाव इति विग्रहः कर्तृसाधननिवृत्त्यर्थः ॥

(उद्द्योतः) भवतेरर्थ इत्येतावता सिद्धे स्वपदेति व्यर्थमत आह—**स्वेति** । न च धातूनामनेकार्थत्वाद्धातुर्न क्वापि लाक्षणिक इति वाच्यम् । अनुपपत्तिप्रतिसन्धानापूर्वकप्रतीतिविषयार्थमादायैवानेकार्थत्वस्वीकारात् । यस्त्वनुपपत्तिप्रतिसंधानपूर्वकप्रतीतिविषयो यथा भूधातोर्गमनादिस्तत्र लक्षणैवेत्याशयात् । क्रियावाचकत्वं च क्रियाबोधकत्वमेवेति बोध्यम् ॥ **प्रकरणादीति** । तेन तत्सापेक्षप्रतीतिकपराभवाद्यर्थनिरासः । भवनलक्षणभावस्य सत्तारूपत्वात्सत्तायाश्च केवलान्वयित्वेन सर्वसमानाधिकरणतया **भाववचन इति** लक्षणं न काप्यव्याप्तमित्युत्तरभाष्यतात्पर्यम् ॥

(आक्षेपभाष्यम्)

यदि भवतेः स्वपदार्थो भवनं भावः । विप्रतिषिद्धानां धातुसंज्ञा न प्राप्नोति—भेदः छेदः । अन्यो हि भावः अन्योऽभावः ॥ आतश्चान्यो भावः अन्योऽभाव इति । यो हि यस्य भावमिच्छति स न तस्याभावम् । यस्य चाभावं न तस्य भावम् ॥ पचादीनां च धातुसंज्ञा न प्राप्नोति यथा हि भवता क्रियावचने धातौ करोतिना पचादीनां सामानाधिकरण्यं निदर्शितम्, न तथा भाववचने धातौ निदर्श्यते । करोतिः पचादीनां सर्वान्कालान्सर्वान्पुरुषान्सर्वाणि वचनान्यनुवर्तते । भवतिः पुनर्वर्तमानकालं चैकत्वं च ॥

(प्रदीपः) **भेद इति** । विनाशो भेदश्छेदश्च घटरज्ज्वादेः स च भावविरोधीति भावः ॥ **सर्वान् पुरुषानिति** । किं करोषि ? पचामि, किं करोमि ? पचेत्यादौ विपरीतापि पुरुषानुवृत्तिः सर्वग्रहणेन विवक्षिता ॥ **भवतिः पुनरिति** । नहि भवति भविष्यति पक्ष्यत्यभूदपाक्षीद्भवतः पचतो भवन्ति पचन्तीति ॥

(उद्योतः) नन्ववयवविभागानुकूलव्यापारवाचिनां भिदादीनां कथमभाववचनतेत्यत आह—**विनाश इति** ॥ तत्र घटादेर्नाशो भेदपदेन, रज्ज्वादेः स च्छेदपदेनेति शब्दशक्तिस्वभावादवगन्तव्यम् । विनाशकाले सत्ताया अभावान्न तेन तस्याः सामानाधिकरण्यमिति भावः ॥ दोषान्तरमाह—**पचादीनां चेति** भाष्ये ॥ **क्रियावचने धाताविति** । क्रियावचनो धातुरिति लक्षणनिरूपणावसरे यथा निदर्शितं न तथा **भाववचनो धातुरिति** लक्षणावसरे पचादीनां भवतिना निदर्श्यत इत्यर्थः । तथाहि न सामान्यविशेषभावेन पचादेर्भवतिना सामानाधिकरण्यम्, किं करोति? पचति, किमकार्षीत् ? अपाक्षीत्, किं करिष्यति? पक्ष्यति, किं कुरुते ? पचते इतिवत् 'किं भवति पचति, किं भविष्यति ? पक्ष्यति' इत्यादेरप्यापत्तेः । यतस्तु न प्रश्नोत्तरभावेन सामानाधिकरण्यं यतश्च पचतौ भिन्नभिन्नवचनान्तेपि भवतेरेकरूपत्वमतः पच्यर्थो भवतेः कर्तैव पचति यत्तद्भवतीति वाक्यार्थात् । **करोतिः** कृधात्वर्थः । **भवतिर्भू**धात्वर्थः । धात्वर्थनिर्देशेपि **यजतिषु ये यजामहं करोती**तिवत् श्तिप् ॥ **वर्तमानकालं चैकत्वं चेति** । प्रश्नविषयत्वं विना चेत्यपि बोध्यम् । **भवतिरेकत्वमनुवर्त्तते** इत्युक्त्या क्रियायां संख्यान्वयं दर्शयति । एवं **पचादीनां सर्वाणि वचनानी**त्यनेनापि । तत्र वचनं संख्या ॥ न चैवं पक्ष्यति भवतीति कथं प्रयोगो भविष्यत्पाके वर्तमानसत्ताश्रयत्वासंभवादिति वाच्यम् । भूतभविष्यतोरपि सूक्ष्मावस्थामालम्ब्य सत्ताया वर्त्तमानत्वाश्रुतेरिति भावः ॥ करोतेः पचादिसर्वपुरुषानुवर्त्तकत्वं । किं करोषि पचामीत्यादौ व्यभिचरितमत आह—**किं करोषीति** । करोतेः सामान्यविशेषभावेन पचादिष्वनुवृत्तिर्द्वेधा पचादिसमानपुरुषान्ता, अनुकूलतद्विपरीतपुरुषान्ता चेति । द्विविधापि सा सर्वपदेन संगृहीतेत्यर्थः ॥ **नहि भवतीति** । ननु यः पक्ष्यति स भविष्यतीत्यभिप्रायेण भविष्यति पक्ष्यतीति प्रयोगः कथं नेति चेन्न । आख्यातस्य क्रियाप्रधानत्वात् । उक्तं सामानाधिकरण्यमपि न भाववाचकतासाधकम्, यथा शुक्लादीनां रूपवाचकत्वेपि न रूपत्ववाचकता तद्वत् । एवं पाकत्वेन सत्तायाः सामानाधिकरण्येन पचेः सद्वाचकत्वेपि न सत्तावाचकत्वमिति बोध्यम् । किं चोक्तोर्थोपि न पचतीत्यनेनैव तत्कर्तुर्वर्तमानसत्त्वावगत्या भवतीत्यस्यानुपयोगात्, तद्वक्ष्यति भाष्ये—**पचादयः क्रिया इत्यादि** ॥

(प्रश्नभाष्यम्)

का तर्हीयं वाचोयुक्तिः—भवति पचति, भवति पक्ष्यति, भवत्यपाक्षीदिति ? ॥

(प्रदीपः) **का तर्हीति** । कथं सम्बन्ध इति प्रश्नः ॥

(उद्द्योतः) **कथं संबन्ध इति** । किंसंबन्धमूलिकेयं वाचोयुक्तिर्वाक्प्रयोगोयमिति भाष्यार्थ इति भावः ॥

(उत्तरभाष्यम्)

एषैषा वाचोयुक्तिः—पचादयः क्रियाः भवतिक्रियायाः कर्त्र्यो भवन्ति ॥

(प्रदीपः) **एषैषेति** । या एषा त्वया पृष्टा सैषा वर्ण्यमानस्वरूपेत्यर्थः ॥ **पचादय इति** । साध्यसाधनभावः सम्बन्धो न तु सामान्यविशेषभाव इत्यर्थः ॥ नन्वन्यत्रोक्तं **तिङभिहितो भावः क्रियया समवायं न गच्छति । नहि भवति पठति पचति** इति । ततश्च तेनैतद्विरुध्येत । तत्राहुः—कर्तृकर्मभावेन क्रिया आख्यातवाच्यक्रियया सम्बध्यत एव—भवति पचति, पश्य मृगो धावतीति । करणादिभावेन तु न सम्बध्यते । तथा प्रयोगादर्शनात् ॥

(उद्योतः) **एषैषेति** द्विरुक्तिः कथमत आह—**यैषेति** ॥ **साध्यसाधनभावः** । क्रियाकारकभावः ॥ **तथा प्रयोगादर्शनादिति** । **ज्योतिष्टोमेन यजेते**त्यादावपि ज्योतिष्टोमेनेत्यस्यैव करणत्वेनान्वयो न तु धात्वर्थस्येति मतं मञ्जूषायां विधिवादे निरूपितं, यद्वा तस्य करणत्वेन न धात्वन्तरार्थेन्वय इति भावः । यत्कर्तृका पचिक्रिया तत्कर्तृका सत्तेति बोधे तु पश्यन्तिभवन्तीत्यादेरप्यापत्तिरिति बोध्यम् ॥

(उत्तरबाधकभाष्यम्)

यद्यपि तावदत्रैतच्छक्यते वक्तुं यत्रान्या चान्या च क्रिया । यत्र खलु सैव क्रिया तत्र कथम्—'भवेदपि भवेत्,' 'स्यादपि स्यात्' इति ॥

(प्रदीपः) **भवेदपि भवेदिति** । एकस्याः क्रियायाः आत्मापेक्षः साध्यसाधनभावो विरुद्ध इति भावः ॥

(उद्योतः) **यत्र खल्विति** । भाष्ये । एकस्या एव कर्तृत्वं तन्निरूपकत्वं च न युक्तमिति भावः ॥ **भवेदपि भवेदितीति** । **अपि भवेदिति** यत्तद्भवत्वित्यर्थः ॥ [भाष्ये **स्यादपि स्यादिति** । अत्र सर्पिष इत्यध्याहारेण पदार्थद्योतकत्वादपेः कर्मप्रवचनीयत्वेन पत्वाभावः ॥]

(उत्तरसाधकभाष्यम्)

अत्राप्यन्यत्वमस्ति । कुतः ? । कालभेदात्साधनभेदाच्च । एकस्यात्र भवतेर्भवतिः साधनं सर्वकालश्च प्रत्ययः । अपरस्य बाह्यं साधनं वर्तमानकालश्च प्रत्ययः । यावतात्राप्यन्यत्वमस्ति, पचादयश्च क्रियाः भवतिक्रियायाः कर्त्र्यो भवन्तीति ॥

(प्रदीपः) **कालभेदादिति** । स्वाभाविकमन्यत्वं कालसाधनभेदेन व्यज्यते ॥ **एकस्येति** । अपि भवेदित्यत्र यो भवतिस्तस्यारोग्यादिविशिष्टदेवदत्तादिकर्तृका सत्ता वर्तमानाऽर्थः तथाभूता हि सत्ता प्रार्थ्यत इति वर्तमानकालः प्रत्ययः । सा तु सत्ता भवेदित्यस्याः सत्तायाः कर्तृत्वेन निर्दिष्टेति भेदोऽस्त्येव ॥

(उद्योतः) नन्वन्यत्वस्य कालभेदजन्यत्वाभावादनुपपन्नमेतदत आह—**स्वाभाविकमिति** । तज्ज्ञानहेतुत्वे तद्धेतुत्वोपचार इति भावः ॥ ननु भवेदपि भवेदित्यस्य देवदत्तस्य सत्ता सम्भाविता इति यत्तद्भवेद्भवत्वित्यर्थः । लिङाऽपिना च संभावना प्रतिपाद्यते । अपरोक्षे लिङ् प्रार्थने । एवं च तयोः कालांशे उदासीनत्वाद्वर्तमानकाल इत्ययुक्तमत आह—**अपि भवेदिति** ॥ **सत्ता वर्तमाने**त्यस्य सम्भावितेति शेषः ॥ यद्यप्युदासीनकाले लिङ् तथापि क्रियाया नियमेन कालाकाङ्क्षासत्त्वात्प्रकरणादिवशेन तत्तत्कालविशिष्टक्रियावगतिः । अत एव माङि लुङादेः सर्वलकारापवादत्वव्यहारः । एवं च **नहि भूतभाविनोस्तादृशी प्रीतिर्यादृशी वर्तमान** इति न्यायेन सम्भावनालिङन्तप्रतिपाद्यस्य वर्तमानत्वसिद्धिस्तदाह—**तथाभूता हीति** ॥ **भवेदित्यस्याः सत्ताया इति** । प्रार्थनालिङन्तार्थाया इत्यर्थः । सम्भावनाविषयवर्तमानसत्ताकर्तृका प्रार्थ्यमाना सत्तेति बोधः ॥ नन्वेवमपि प्रार्थनालिङन्तार्थस्य कथं सर्वकालत्वं प्रार्थनाया भविष्यद्विषयतया तद्विषयसत्तायां भविष्यत्त्वप्रतीतेरिति चेन्न । शान्तो रोग इति प्रश्ने पुनरनुत्पत्तिध्वननार्थेकेन शमिष्यतीत्युक्ते संवादायापरेण शाम्यतीत्युक्तेऽनौचित्यपरिहाराय शाम्यत्विति प्रयोगदर्शनेन प्रार्थनाविषये सर्वकालत्वाभिमानात् ॥ तदेवमत्र लक्षणे भिदादिष्वव्याप्तिर्भवतिसामानाधिकरण्याभावात्पचादावव्याप्तिश्चेति दूषणद्वयं स्थितम् ॥ **कर्त्र्यो भवन्ती**त्यस्यानुपपन्नं **भाववचनो धातुरिति लक्षणमिति** शेषः । भवतिसामानाधिकरण्याभावेन भाववचनत्वाभावादिति भावः ॥

(समाधानभाष्यम्)

अस्त्वयं कर्तृसाधनः—भवतीति भाव इति ॥ किं कृतं भवति ? । विप्रतिषिद्धानां धातुसंज्ञा सिद्धा भवति ॥

(प्रदीपः) **अस्त्वयमिति** । भेदादयोपि भवन्तीति तद्वचनानां सिध्यति धातुसंज्ञा ॥

(उद्योतः) अथ तदुद्धरति—**अस्त्विति** । **विप्रतिषिद्धाना**मित्युपलक्षणं पचादीनामपि ॥ **भेदादयोपीति** । जन्मवाची भवतिस्तेन ध्वंसस्यापि जायमानत्वान्नाव्याप्तिरिति भावः । अन्योन्याभावोपि तत्तद्वस्तुजन्मना जन्य एवेति तद्वाचकभेदशब्दसिद्धिर्बोध्या ॥

(आक्षेपभाष्यम्)

भवेद्विप्रतिषिद्धानां धातुसंज्ञा सिद्धा स्यात्, प्रातिपदिकानामपि तु प्राप्नोति वृक्षः प्लक्ष इति ॥ किं कारणम् ? । एतान्यपि हि भवन्ति ॥

(प्रदीपः) **एतान्यपीति** । एतत्प्रतिपाद्यानि वस्तूनीत्यर्थः ॥

(उद्योतः) **एतानीति** नपुंसकमयुक्तमुपक्रान्तानां पुंस्त्वादत आह—**एतदिति** ॥

(समाधानभाष्यम्)

एवं तर्हि कर्मसाधनो भविष्यति—भाव्यते यः स भाव इति। क्रिया चैव हि भाव्यते। स्वभावसिद्धं तु द्रव्यम्॥

(प्रदीपः) भाव्यते यः स भाव इति। तेन साध्यमानार्थवाचिनां धातुसंज्ञेत्यर्थः॥ **स्वभावसिद्धमिति**। शब्दशक्त्यनुसारेणैतदुच्यते। कृतताक्रियमाणताकर्तव्यता—युक्तान्यपि द्रव्याणि सिद्धरूपाण्येव प्रातिपदिकेनाभिधीयन्ते। शब्दान्तरेण तु तेषामवस्थान्तरं प्रतिपाद्यते॥

(उद्द्योतः) ननु कर्मसाधनेपि वृक्षादिषु दोषोऽपरिहृत एवेत्यत आह—**तेन साध्यमानेति**। साध्यावस्थापन्नार्थवाचिनामित्यर्थः॥ **कृतता**, घटमकार्षीदित्यादौ। **क्रियमाणता**, घटं करोतीत्यादौ। **कर्तव्यता**, घटं करिष्यतीत्यादौ॥ **सिद्धरूपाण्येवेति**। **स्वभावेन** शब्दशक्तिस्वभावेन **सिद्धं** सूक्ष्मरूपेण सिद्धावस्थमेव **द्रव्यं** शब्दवाच्यमिति भाष्याक्षरार्थः। अत एव तस्य क्रियाकाङ्क्षा। यद्यपि क्रियापि तथा तथापि सा शब्दशक्तिस्वभावात् स्थूलरूपेण साध्यतयैव प्रतीयत इति बोध्यम्॥

(आक्षेपभाष्यम्)

एवमपि भवेत्केषांचिन्न स्यात्—यानि न भाव्यन्ते। ये त्वेते संबन्धिशब्दास्तेषां प्राप्नोति माता पिता भ्रातेति। सर्वथा वयं प्रातिपदिकपर्युदासान्न मुच्यामहे॥

(प्रदीपः) **मातेति**। मातृत्वं पुत्रजन्मना भाव्यते॥ **सर्वथेति**। पाठाश्रये समानशब्दानां प्रसङ्गः कर्तृसाधने भावशब्दे वृक्षादीनां प्रसङ्गः कर्मसाधने मात्रादीनामित्यर्थः॥

(उद्द्योतः) **मातृत्वमिति**। मात्रादिशब्दा जनकस्त्रीत्वादौ शक्ता जनकत्वस्य च जन्यनिरूपितत्वमित्यभिमानः॥

(समाधानभाष्यम्)

पठिष्यति ह्याचार्यः—* भूवादिपाठः प्रातिपदिकाणवयत्यादिनिवृत्त्यर्थः—* इति। यावता पठिष्यति पचादयश्च क्रियाः भवतिक्रियायाः कर्त्र्यो भवन्तीति अस्त्वयं कर्तृसाधनो भवतीति भाव इति॥

किं वक्तव्यमेतत्?॥

नहि॥

कथमनुच्यमानं गंस्यते?॥

एतेनैवाभिहितं सूत्रेण "भूवादयो धातवः" इति॥

कथम्?।

नेदमादिग्रहणम्। वदेरयमौणादिक इकर्तृसाधनः—भुवं वदन्तीति भूवादय इति॥

(प्रदीपः) इदानीं समाधानमाह—**पठिष्यतीति**। पठितानामेव भाववचनानां धातुसंज्ञा नान्येषामित्यर्थः॥ **अस्त्वयमिति**। भवतीति भूरिति कर्तरि क्विबस्ति न तु कर्मणि। अर्थस्त्वभिन्न एव। यो हि भवति स एव भाव्यते नान्यः॥ **नेदमिति**। वृद्धिशब्दस्य मङ्गलार्थस्य प्रयुक्तत्वादकारो मङ्गलार्थो नोपयुज्यते॥ **भुवमिति**। जायमानमर्थं येऽभिदधति ते धातव इत्यर्थः। भवतिरत्र जन्मवाची गृह्यते न तु सत्तावाचीति सिद्धार्थाभिधायिनां संज्ञा न भवति॥

(उद्योतः) भाष्ये पठिष्यति हीत्यस्य हिशब्दात् पूर्वोक्तश्लोकपादकृतत्वभ्रमं वारयति—**इदानीमिति**॥ समानशब्दातिप्रसङ्गवारणायाह—**भाववचनानामिति**। कर्त्र्यो भवन्तीत्यतोऽस्त्वयं कर्तृसाधनो भवतीति भाव इति न कश्चिद्दोष इत्यर्थो भाष्यस्य॥ सूत्राक्षरस्य संग्रहं दर्शयति—**भूरिति कर्तरीति**॥ **अर्थस्त्वभिन्न एवेति**। एवं च कर्तृसाधनकर्मसाधनयोरविशेषः, फले दोषवारणमपि समम्, न्यायप्राप्तश्च कर्तृसाधन इति स एवास्त्वित्याशयः॥ भाष्ये—**किं वक्तव्यमिति**। भाववचना भूवादयो धातव इति किं वक्तव्यमित्यर्थः॥ भाष्ये **औणादिक इति**। बाहुलकादिति भावः॥ **वृद्धिशब्दस्येति**। मध्यमङ्गलस्य शिवशमरिष्टस्येत्यादिभिरेव सिद्धत्वेनेदं नातीवोपयुज्यत इति भावः॥ **जायमानमिति**। तत्त्वेन प्रतीयमानमित्यर्थः॥

(८१८ प्रथमाक्षेपवार्तिकम्॥ १३॥)

॥ * ॥ भाववचने धातौ तदर्थप्रत्ययप्रतिषेधः॥ * ॥

(भाष्यम्) **भाववचने धातौ तदर्थस्य प्रत्ययस्य प्रतिषेधो वक्तव्यः। शिश्ये इति॥ किं च स्यात्?। अशितीत्यात्वं प्रसज्येत। तद्धि धातोर्विहितम्॥**

(प्रदीपः) **शिश्ये इति**। भावार्थाभिधायित्वात्प्रत्ययस्य धातुसंज्ञाप्रसङ्गादात्वं प्राप्नोति। तच्चानैमित्तिकं शिति तु प्रतिषिध्यते। एकारोच्चारणं तु यदा कर्तृकर्मणोर्लकारस्तदर्थम्। पाठस्तु न तावदस्य मनसि वर्तते॥

(उद्द्योतः) एवं वदतानेन प्रातिपदिकनिवृत्त्यर्थं पाठो नाश्रितः। वृक्षादीनां तत्त्वेनाभानादेव व्यावृत्तिसिद्धेरिति मन्वानः शङ्कते—भाष्ये—**भाववचन इत्यादि**॥ **प्रत्ययस्येति**। प्रत्ययान्तस्य तूपदेशाभावाद्धातुत्वेप्यात्वाप्राप्तेरिति भावः॥ **अशितीति** पर्युदासेनाशितः परत्वाभावादात्वाप्राप्तिरत आह—**तद्धीति**॥ भाष्ये **तद्धि धातोरिति**। आदेच इत्यत्र धातोरिति संबध्यत इति वार्तिककृतोऽभिमान इति भावः॥ भाष्यकारस्तूपदेशग्रहणबलेन तत्र धातोरित्यस्यासंबन्धं वक्ष्यति। अत्र तु नात्वं शिति नेति निषेधेन शित्प्रत्ययपरत्वयोग्य एवैजन्त आत्वप्रवृत्तेरिति बोध्यम्॥ यं विधिं प्रतीतिन्यायेनैकारोच्चारणसामर्थ्यादात्वं न स्यादत आह—**एकारोच्चारणं त्विति**॥

(८१९ द्वितीयाक्षेपवार्तिकम् ॥ १४ ॥)

॥ इतरेतराश्रयं च प्रत्यये भाववचनत्वं तस्माच्च प्रत्ययः ॥ * ॥

(भाष्यम्) इतरेतराश्रयं च भवति ॥ का इतरेतराश्रयता? । प्रत्यये भाववचनत्वं तस्माच्च प्रत्ययः । उत्पन्ने हि प्रत्यये भाववचनत्वं गम्यते स च तावद्भाववचनादुत्पाद्यः । तदेतदितरेतराश्रयं भवति । इतरेतराश्रयाणि च कार्याणि न प्रकल्पन्ते ॥

(प्रदीपः) इतरेतराश्रयं चेति । प्राक् शास्त्रव्यापारात्समुदाय एव नास्ति, कुतोन्वयव्यतिरेकाभ्यामर्थस्य प्रविभागः ॥ तस्मिंश्चासति भाववचनापरिज्ञानाद्धातुत्वं न व्यवतिष्ठत इत्यर्थः॥

(८२० द्वितीयाक्षेपसमाधानवार्तिकम् ॥ १५ ॥)

॥ * ॥ सिद्धं तु नित्यशब्दत्वादनाश्रित्य भाववचनत्वं प्रत्ययः ॥ * ॥

(भाष्यम्) सिद्धमेतत् ॥ कथम्? । 'नित्यशब्दत्वात् ।' नित्याः शब्दाः । नित्येषु च शब्देषु अनाश्रित्य भाववचनत्वं प्रत्यय उत्पद्यते ॥

(प्रदीपः) सिद्धं त्विति । व्यवस्थिता एव पचत्यादयः समुदायाः संसृष्टार्थाभिधायिनः केवलमुत्प्रेक्ष्योत्प्रेक्ष्य प्रक्रियायामर्थविभागः शब्दविभागश्चापोद्ध्रियते इत्यर्थः ॥ अनाश्रित्येति । पारमार्थिकं नाश्रीयते, परिकल्पितं त्वाश्रीयत एव । तत्त्वतो हि शब्दान्तराण्येवार्थान्तरेषु प्रयुज्यन्ते ॥

(उद्योतः) व्यवस्थिता इति साधुत्वान्वाख्यानमात्रे शास्त्रव्यापारात् प्रागुक्तप्रणाडी सर्वापि सिद्धैवेति नान्योन्याश्रय इति भावः ॥ संसृष्टार्थाभिधायिन इति । संसृष्टोपस्थापका इत्यर्थः ॥ धातुसंज्ञार्थं भाववचनत्वस्याश्रितत्वादनाश्रित्येत्यनुपपन्नमत आह— पारमार्थिकमिति । तस्य व्यवहारेण समुदायवृत्तित्वादिति भावः ॥ वार्तिककृताऽनाश्रित्येत्युक्तेरिति तात्पर्यम् ॥ परिकल्पितं त्विति । भाष्यकृता पूर्वमन्वयव्यतिरेकाभ्यां धातुरेव क्रियावाचीत्युक्तेरिति भावः ॥

(८२१ प्रथमाक्षेपसमाधानवार्तिकम् ॥ १६ ॥)

॥ * ॥ प्रथमभावग्रहणं च ॥ * ॥

(भाष्यम्) प्रथमभावग्रहणं च कर्तव्यम् । प्रथमं यो भावमाहेति ॥ कुतः पुनः प्राथम्यम् । किं शब्दत आहोस्विदर्थतः? । किं चातः? । यदि शब्दतः, सनादीनां धातुसंज्ञा न प्राप्नोति—पुत्रीयति वस्त्रीयतीति । अथार्थतः, सिद्धा सनादीनां धातुसंज्ञा, स एव तु दोषः * भाववचने तदर्थप्रत्ययप्रतिषेधः * इति ॥ एवं तर्हि नापि शब्दतो नाप्यर्थतः ॥ किं तर्हि? । अभिधानतः । सुमध्यमेभिधाने यः प्रथमं भावमाह ॥

(प्रदीपः) प्रथमभावग्रहणं चेति । तदर्थप्रत्ययपरिहारोयम् ॥ प्राथम्यस्यापेक्षिकत्वात्पृच्छति—कुत इति ॥ पुत्रीयतीति । नात्र प्रथममुच्चार्यमाणः पुत्रशब्दो भावमाह । सनाद्यन्तां धातव इत्यस्य प्रत्याख्यानेऽयं दोषः ॥ सिद्धेति । प्रथम आद्यो भावोप्रथमेनापि क्यचाभिधीयते न तु द्वितीयः । शिष्य इत्यत्र तु प्राप्नोति । स्वार्थिकेन प्रत्ययेन प्रथम एव भावोभिधीयते न तु द्वितीयः ॥ अभिधानत इति । अन्येनानभिहितं भावं य आह स धातुः । शिष्ये इत्यत्र तु प्रकृत्यभिहितं भावं प्रत्यय आहेति न तस्य धातुसंज्ञाप्रवृत्तिः । यथा प्रथममयं राजानं पश्यतीत्यस्यायमर्थो यदन्येनादृष्टं पश्यतीति तथेहापि प्राथम्यमभिधानक्रियापेक्षमाश्रीयते अन्येभ्यो भावाभिधायिभ्यो यः प्रथमं भावमाहेति ॥ सुमध्यम इति । द्वौ शब्दार्थपक्षौ दुष्टत्वात्परित्यज्योपादीयमानमभिधानं मध्यममिति व्यपदिश्यते । तदेव निर्दोषत्वाच्छोभनत्वेन विशेष्यते । चिकीर्षतीत्यत्र करोत्यर्थोपसर्जनामिच्छामन्येनानभिहितां सन्प्रत्यय आहेति प्रवर्तते धातुसंज्ञा । अत्र पक्षे यथा शिष्य इति प्रत्ययस्य धातुसंज्ञा न भवति तथा स्वार्थिकानामायादीनामपि न प्राप्नोति गोपायति कामयते इति । तदर्थं सनाद्यन्ता धातव इति पठितव्यमेव ॥

(उद्योतः) चश्रवणाद्दोषसमुच्चय इति भ्रमं प्राप्तं वारयति—तदर्थेति । वार्तिककृता धातोरित्यस्यात्वे संबन्धाभ्युपगमादुक्तोयं परिहार इत्यर्थः ॥ ननु स्वभावादेव धातूनां प्रथमं भाववाचित्वे कुत इति हेतुप्रश्नोऽसंगत इत्यत आह—प्राथम्यस्येति । अवधिविषयः प्रश्न इति भावः ॥ प्रथमश्चासौ भाववचनश्चेति विग्रहे प्रथममुच्चार्यमाणः सन् भावमाहेत्यर्थे शब्दतः प्राथम्यम्, प्रथमस्य भावस्य वचन इति विग्रहेऽर्थतः, द्वयोर्मध्ये प्रथमं पूर्वकालं भाववचनमिति विग्रहे विस्पष्टपटुवत्समासेऽभिधानतः स्वयं प्रथमोऽप्रथमो वा प्रथममप्रथमं वा भावमन्येभ्यः पूर्वमाहेत्यर्थादिति बोध्यम् ॥ नात्रेति । यद्यपि तिङपेक्षया क्यजपि प्रथमस्तथापि तस्य गौणं प्राथम्यमिति भावः । न च क्यजन्तस्य तिङपेक्षया मुख्यमेव प्राथम्यम् । पुत्र इच्छा आश्रय इत्यर्थत्रयावभासेन खण्डत्रयस्यैव करणादिति तत्त्वम् ॥ ननु सनाद्यन्ता इति तस्य धातुत्वं सिद्धमत आह—सनाद्यन्ता इति ॥ भाववचना इति लक्षणे सनाद्यन्तानामप्यनेनैव धातुत्वसिद्धौ तत्सूत्रमेव प्रत्याख्येयमिति भावः ॥ क्यचेति । लक्षणे भाववचनस्तदन्तश्च गृह्यते इति तदन्तस्य धातुत्वसिद्धिरिति भावः ॥ प्रथममयं राजानमिति । प्रथममयमेव राजानमित्यर्थः ॥ नन्वस्य पक्षस्यान्त्यत्वान्मध्यम इत्ययुक्तमत आह—द्वाविति । उभयास्पृष्टे मध्यस्थ इति व्यवहारात् प्रागुक्तदोषद्वयास्पर्शेनायं मध्यम इति भावः ॥ इच्छामन्येनेति । एवं प्रतीषिषतीत्यादावपि प्रकृत्यर्थातिरिक्तां तद्विषयामिच्छामन्येनानभि-

हितामेव सत्त्राहेति बोध्यम् ॥ आयादीनामिति । तदन्तानामित्यर्थः ॥

(क्रियावचनवादिभाष्यम्)

इह ये एव भाववचने धातौ दोषास्ते क्रियावचनेपि। तत्र त एव परिहाराः।

(प्रदीपः) इहेति । तदर्थप्रत्ययप्रतिषेध इतरेतराश्रयं च। प्रथमभावग्रहणं च सिद्धं तु नित्यशब्दत्वादिति च। केवलं प्रथमभावग्रहणमपनीय प्रथमक्रियाग्रहणं चेति क्रियाग्रहणं कर्तव्यम् ॥

(उद्योतः) क्रियावचनपक्षे प्रथमभावपदस्यानन्वयात्त एव परिहारा इत्यसङ्गतमत आह—तदर्थेत्यादि। भिदादीनामपि विभागफलकव्यापारवाचित्वात् क्रियावाचित्वमस्त्येव। अभावोपि सूक्ष्मावस्थस्यैवेत्यभाववाचिनामपि भाववचनत्वमभावस्यालीकत्वाभ्युपगमादिति बोध्यम् ॥

(आक्षेपभाष्यम्)

तत्रेदमपरिहृतम्—अस्तिभवतिविद्यतीनां धातुत्वम्—इति ॥

(प्रदीपः) तत्रेदमिति । किं करोतीति प्रश्नेऽस्त्यादिभिः प्रतिवचनाभावादक्रियावचनत्वमेषामिति मन्यते । यथाप्युक्तमिह सर्वेषु साधनेषु सन्निहितेषु कदाचित्पचतीत्येतद्भवति कदाचिन्नेति तदस्त्यादिषु नास्ति । नह्यस्तीति कदाचिद्भवति, अपि तु सर्वदेति पाकादिभिर्वैधर्म्यम् । यथा च पचतितरामिति प्रकर्षो भवति नैवमस्तितरामिति ॥

(उद्योतः) भाष्ये तत्रेदमिति। तत्र क्रियावचनो धातुरिति लक्षणे क्रियावचनत्वाभावादप्राप्तं धातुत्वमस्त्यादीनामिति भावः ॥ कुतोऽक्रियात्वं तेषामत आह—किं करोतीति ॥ नह्यस्तीति । साधनसन्निधानेऽस्तीति कदाचिद्भवतीति न, अपि तु सर्वदा भवत्येवेत्यन्वयः ॥

(प्रत्याक्षेपभाष्यम्)

तस्य परिहारः। कां पुनः क्रियां भवान्मत्वाह—अस्तिभवतिविद्यतीनां धातुसंज्ञा न प्राप्नोतीति। किं यत्तद्देवदत्तः कंसपात्र्यां पाणिनौदनं भुङ्क्ते इति ॥

(प्रदीपः) किं यत्तदिति। यत्तच्छब्दाभ्यां कारकवैचित्र्यं निर्दिश्यते ॥

(उद्योतः) क्रियास्वरूपं शङ्कितैव वाचयितुं पृच्छति—भाष्ये कां पुनरिति ॥ तदाशयं स्वयमेवोन्नीयाह—किं यदिति। एवं हि भुजिकारकस्येवास्तिकारकस्यापि क्रियात्वमस्तु का क्षतिरिति भावः ॥ ननु भुङ्क्ते इति यस्सा क्रियेत्यन्वये धात्वर्थक्रियावाद एवोपक्षिप्तः स्यादिति न ब्रूम इत्यादिग्रन्थासङ्गतिः, देवदत्त इति यस्सा क्रियेत्याद्यन्वये यत्तदोः प्रधानपरामर्शित्वहानिरत आह—यत्तदिति। क्रियांशस्य प्राधान्येपि न तात्पर्यविषयता सर्वनाम्नां गुणपरामर्शकता च दृष्टाऽतस्तत्तद्व्यापाराविष्टकारकाण्येव ताभ्यां परामृश्यन्त इत्यर्थः ॥ कारकवैचित्र्यमित्यस्य, विचित्राणि कारकाणीत्यर्थः। स्वार्थे ष्यञिति बोध्यम्। वैचित्र्यं च तत्तद्व्यापाराविष्टत्वमेव ॥

(प्रत्याक्षेपसमाधानभाष्यम्)

न ब्रूमः कारकाणि क्रियेति। किं तर्हि?। कारकाणां प्रवृत्तिविशेषः क्रिया। अन्यथा च कारकाणि शुष्कौदने प्रवर्तन्ते, अन्यथा च मांसौदने ॥

(प्रदीपः) प्रवृत्तिविशेष इति। सर्वा प्रवृत्तिः प्रवृत्त्यन्तराद्भिद्यते इत्यस्त्येव सर्वस्याः क्रियात्वम् ॥ अन्यथेति। शुष्कौदने मन्दप्रयत्नः प्रवर्तते मांसौदने तु संवेगेन। यथा च भोजनक्रियाणां परस्परवैलक्षण्यात्प्रवृत्तिविशेषत्वं नैवमस्त्यादीनाम् ॥

(उद्योतः) भाष्ये शङ्किताऽऽह—न ब्रूम इत्यादि ॥ प्रवृत्तिविशेष इति। स चास्त्याद्यर्थेनास्तीति भावः ॥ एतच्चोपलक्षणं प्रतिवचनादीनामिति तान्युक्तवानुपाध्यायः ॥ ननु प्रवृत्तिविशेषस्य क्रियात्वे प्रवर्ततइत्यत्र क्रियात्वानापत्तिरत आह—सर्वेति। पच्याद्यपेक्षया सापि विशेष एवेति भावः। शङ्किताशयमुपसंहरति—यथा चेति। एवं चास्त्यादौ धातुत्वासिद्धिरिति भावः ॥

(समाधानभाष्यम्)

यद्येवं सिद्धास्तिभवतिविद्यतीनां धातुसंज्ञा। अन्यथा हि कारकाण्यस्तौ प्रवर्तन्तेऽन्यथा हि म्रियतौ ॥

(प्रदीपः) यद्येवमिति। अत्रापि प्रवृत्त्यन्तरापेक्षयास्त्येव प्रवृत्तिविशेषरूपत्वमित्यर्थः ॥ अन्यथेति। अस्तावात्मभरणरूपा प्रवृत्तिर्म्रियतौ तत्त्यागरूपा। उत्पत्तिप्रभृत्याविनाशाच्च सत्तानुषङ्गादस्तीति प्रत्ययस्य सन्निहितेषु साधनेषूत्पत्तिरवश्यं भाविनीति कादाचित्कत्वाभावः। प्रकर्षप्रत्ययोपि दृश्यते विद्यतेतरामिह धान्यमिति।

(उद्योतः) सिद्धान्त्याह—भाष्ये—यद्येवमिति ॥ अन्यथा हीति। कारककर्तृकाऽस्तौ वाच्यत्वेन स्थिता प्रवृत्तिरन्यथेत्यक्षरार्थस्तदेवाह—आत्मभरणरूपेति। स्थूलरूपधारणानुकूलव्यापाररूपेत्यर्थः। म्रियतौ तत्त्यागानुकूलव्यापाररूपेति भावः। एवं च म्रियत्यपेक्षया प्रवृत्तिविशेषरूपतास्त्येवास्त्यर्थस्येति तात्पर्यम् ॥ पूर्वोक्तदूषणत्रयमेवन्त्यद्वयमुद्धरति—उत्पत्तीत्यादि। कादाचित्कत्वाभाव इति। अयं चात्मभरणलक्षणसत्तावाचिन्येव। तदपि कर्तृरूपे वस्तुनि विद्यमाने एव वस्तुकादाचित्कताप्रयुक्ता तु सास्त्येव। अत एव भूतभविष्यत्प्रयोगाः सङ्गच्छन्ते। उत्पत्तिरूपसत्तावाचिनि तु कादाचित्कताप्यस्त्येव। विद्यतेतरामित्यपि कारकगतप्रकर्षारोपेणैव बोध्यम् ॥

(समाधानसाधकप्रमाणभाष्यम्)

षड्भावविकारा इति ह स्माह वार्ष्यायणिः । जायतेऽस्ति विपरिणमते वर्द्धतेऽपक्षीयते विनश्यतीति ॥

(प्रदीपः) अत्रैवार्थे आगममाह—**षड् भावविकारा इति** । भावस्य क्रियायाः षड् प्रकारा इत्यर्थः । तेषु चास्तिः पठित इति तस्यापि क्रियात्वमित्यर्थः । अथ वा भावस्य सत्ताया एते प्रकाराः । सत्तैवानेकक्रियात्मिका साधनसम्बन्धादवसीयमानसाध्यरूपा जन्मादिरूपतयावभासते । एते च भावविकारा निरुक्ते निपुणं व्याख्याताः । इह तु प्रकृतानुपयोगान्न व्याख्यायन्ते ॥

(उद्योतः) भाष्येऽस्त्यादीनां क्रियावाचकत्वे युक्त्यन्तरमाह—**षड्भावेत्यादि** ॥ **क्रियाया इति** । भावो लीला क्रिया चेष्टेति कोशादिति भावः । **विकारशब्दः** प्रकारवाची ॥ **अथ वेति** । उत्पत्तिविनाशयोरपि सूक्ष्मरूपेण वस्तुनो भावात्तेषामपि सत्तात्मकत्वमिति बोध्यम् । भावस्य सत्ताया ब्रह्मसत्ताया एते विकाराः क्रियाप्रकारा मायावशात्त इव भासमाना इति वार्ष्यायण्युक्तेरर्थः ॥ **सत्तैवेत्यादि** ब्रह्मसत्तैवानेकक्रियात्मिकानेकक्रियाविवर्त्तात्मिका साधनैः कारकैः संबन्धादवसीयमानसाध्यस्वरूपा जन्मादिरूपतया भासत इत्यर्थः । एतच्च निरुक्तभाष्ये स्पष्टम् ॥

(दूषणभाष्यम्)

सर्वथा स्थित इत्यत्र धातुसंज्ञा न प्राप्नोति । बाह्यो ह्येतेभ्यस्तिष्ठतिः ॥

(प्रदीपः) **सर्वथेति** । भावविकारपरिसङ्ख्यानस्याव्यापकत्वमित्यर्थः ॥

(उद्द्योतः) **भावविकारेति** । एवं चाव्याप्तिदूषितं परिगणनं कथमस्त्यंशे प्रमाणं भवेदिति भावः ॥

(समाधानभाष्यम्)

एवं तर्हि क्रियायाः क्रिया निर्वर्तिका भवति, द्रव्यं द्रव्यस्य निर्वर्तकम् । एवं हि कश्चित्कंचित्पृच्छति—'किमवस्थो देवदत्तस्य व्याधिः' इति?। स आह—'वर्द्धते' इति । अपर आह—'अपक्षीयते' इति । अपर आह—स्थित इति । स्थित इत्युक्ते वर्द्धतेश्चापक्षीयतेश्च निवृत्तिर्भवति ॥

(प्रदीपः) **एवं तर्हीति** । अनुमानेन स्थानस्य क्रियात्वं प्रतिपादयति । अन्यथा स्थित इत्युक्ते वृद्धिक्षयनिवृत्तिर्न प्रतीयेत ॥

(उद्द्योतः) **अनुमानेनेति** । षड्भावविकारेष्वभावादक्रियात्वमेव मन्यमानं प्रतीत्यादिः ॥ **अन्यथेति** । एवं च स्थितेरप्यस्तितायामन्तर्भावान्न परिगणनाव्याप्तिरिति भावः ॥

(समाधानान्तरभाष्यम्)

अथ वा नान्तरेण क्रियां भूतभविष्यद्वर्तमानाः कालाः व्यज्यन्ते । अस्त्यादिभिरपि भूतभविष्यद्वर्तमानकालाः व्यज्यन्ते ॥

(प्रदीपः) **अथवेति** । क्रियान्तरधर्मसमन्वयेनास्त्यादीनां क्रियात्वं प्रतिपाद्यते । घट इत्युक्ते कालविशेषावगतिर्नास्ति । अस्ति अभूद् भविष्यतीति कालविशेषावगमात् साध्यमानस्य चार्थस्य कालेन योगात् क्रियात्वावसायः ॥

(उद्द्योतः) तिष्ठतेरेव क्रियात्वे युक्त्यन्तरमिति भ्रमं वारयति—**क्रियान्तरेति** । एतन्मूलिकैव **क्रियाभेदाय कालस्त्विति** वाक्यपदीयोक्तिः कालस्य क्रियामात्रपरिच्छेदकत्वादिति भावः ।

(समाधानान्तरभाष्यम्)

अथ वा नान्यत्पृष्टे नान्यदाख्येयम् । तेन न भविष्यति—किं करोत्यस्तीति ॥

(प्रदीपः) **अथ वेति** । निर्ज्ञातायां सत्तायां किं करोतीति प्रश्नासम्भवादस्तीति प्रतिवचनाभावः । न तु क्रियात्वाभावादित्यर्थः । यदा तु प्रत्यासन्नविनाशशङ्कया देवदत्तः किं करोतीति प्रश्नः । तदास्ति तावदिति प्रतिवचनं भवत्येव ॥

(उद्द्योतः) ननु यद्यस्त्यादेः क्रियावाचित्वं तर्हि किं करोतीति पृष्टेऽस्तीत्याद्युत्तरं कुतो नेत्यतो भाष्ये—**अथवा नान्यदिति** । अत्राथवेति यत इत्यर्थे । **प्रश्नासम्भवादिति** । निर्ज्ञातत्वेन सत्ताविषयप्रश्नासम्भवादित्यर्थः ॥

(आक्षेपभाष्यम्)

अथ यद्येव "क्रियावचनो धातुः" इत्येष पक्षः । अथापि "भाववचनो धातुः" इति । किं गतमेतदियता सूत्रेण, आहोस्विदन्यतरस्मिन्पक्षे भूयः सूत्रं कर्तव्यम्? ॥

(प्रदीपः) **अथ यद्येवेति** । परिस्पन्दापरिस्पन्दरूपतया क्रियाभावयोर्भेदेनोपन्यासः ॥

(उद्द्योतः) ननु क्रियाभावयोरेकार्थतया कथमिह भेदेनोपादानमत आह—**परिस्पन्देति** । आदिशब्दयोर्व्यवस्थाप्रकारवाचिनोरेकशेषः । सादृश्यं चान्यानभिहितसाध्यावस्थापन्नार्थवाचित्वेनेति नाव्याप्तिः ॥

(समाधानभाष्यम्)

गतमित्याह । कथम्? । अयमादिशब्दोऽस्त्येव व्यवस्थायां वर्तते, तद्यथा—देवदत्तादीन्समुपविष्टानाह देवदत्तादय आनीयन्तामिति । ते उत्थाप्यानीयन्ते । अस्ति प्रकारे वर्तते, तद्यथा—देवदत्तादय आढ्या अभिरूपा दर्शनीयाः पक्षवन्तः । देवदत्तप्रकारा इति गम्यते ॥ प्रत्येकं चादिशब्दः परिसमाप्यते—भ्वादय इति च वादय इति च ।

तद्यदा तावत् 'क्रियावचनो धातुः' इत्येष पक्षः तदा भू इत्यत्र य आदिशब्दः स व्यवस्थायां वर्तते, वा इत्यत्र य आदिशब्दः स प्रकारे, भूइत्येवमादयो वाइत्येवंप्रकारा इति । यदा तु 'भाववचनो धातुः' इत्येष पक्षस्तदा वेत्यत्र य आदिशब्दः स व्यवस्थायाम्, भू इत्यत्र य आदिशब्दः स प्रकारे, वा इत्येवमादयो भू इत्येवंप्रकारा इति ॥

(प्रदीपः) तदा वेत्यत्रेति। अदादीनामादौ वा गतिगन्धनयोरिति पठितव्यम् । अदादिगणोऽपि गणानामादौ । तेन सर्वे धातुपाठसन्निविष्टा गृहीता भवन्ति ॥

(उद्द्योतः) तत्र वाप्रभृतयो भूप्रकारा इत्यर्थे वाधातोः प्राचीनानां न स्यादित्यत आह—अदादीनामिति । अविप्रभृतिभ्य इत्यस्य स्थाने वाप्रभृतिभ्य इत्येव पठनीयम् । अविप्रभृतिभ्य इत्यत्र बहुव्रीहितत्पुरुषयोरेकशेषो वा बोध्यः ॥

(आक्षेपभाष्यम्)

यदि तर्हि लक्षणं क्रियते नेदानीं पाठः कर्तव्यः॥

(प्रदीपः) यदि तर्हीति ॥ क्रियावचनो धातुरिति वा भाववचनो धातुरिति वा लक्षणं क्रियते नार्थः पाठेनेत्यर्थः ।

(उद्द्योतः) ननु व्यवस्थावाच्यादिशब्दान्तर्भावेण पाठस्यापि लक्षणेनापेक्षणीयत्वान्नेदानीमित्ययुक्तमत आह—क्रियावचनं इति।

(समाधानभाष्यम्)

कर्तव्यश्च । किं प्रयोजनम् ? ।

(उद्द्योतः) व्यवस्थावाच्यादिशब्दस्य प्रयोजनप्रश्न इत्यर्थः ॥

(८२२ पाठप्रयोजनवार्तिकम् ॥ १७ ॥)

॥ * ॥ भूवादिपाठः प्रातिपदिकाणवयत्यादिनिवृत्त्यर्थः ॥ * ॥

(भाष्यम्) भूवादिपाठः कर्तव्यः ॥ किं प्रयोजनम् ? । प्रातिपदिकाणवयत्यादिनिवृत्त्यर्थः । प्रातिपदिकनिवृत्त्यर्थं आणवयत्यादिनिवृत्त्यर्थश्च ॥ के पुनराणवयत्यादयः ? । आणवयति वट्टति वड्ढयतीति ।

(प्रदीपः) भूवादिपाठ इति । यथा भोक्तुं पाक इति क्रियाश्रयाणि तुमुनादीनि भवन्ति तथा धातुसंज्ञापि स्यादिति पाकादीनां शयितव्यादीनां च प्रातिपदिकानां पाठेनासौ निवर्त्यते । तथा हिरुक् पृथग् इत्यादीनां च क्रियाप्रधानानामव्ययानाम् ।

(उद्योतः) ननु भावक्रियापदयोः साध्यावस्थापन्नार्थाभिधायित्वात् प्रातिपदिकेषु कथमतिप्रसङ्गोऽत आह—यथेति । भोक्तुं भुक्त्वेत्यादि प्रातिपदिकं व्यावर्त्यं बोध्यम् । पाकपदेन सिद्धावस्थस्य भानाद् भोक्तुं पाक इति प्रयोगोपि चिन्त्य इत्युपपदमतिङितिसूत्रे वक्ष्यते। फलं तु पाकादिशब्दे इवाग्रापि ॥ हिरुगिति । क्रियान्तराकाङ्क्षादर्शनेनैषां क्रियावाचित्वं चिन्त्यम् । अत एव तद्धितश्चासर्वविभक्तिरितिसूत्रे क्रियामात्रविशेषणत्वात् क्रियाप्रधानत्वमेषां स्वयमुक्तम् । शिश्ये इत्यादिव्याख्यातिस्त्वन्यानभिहितक्रियावाचकत्वेन सादृश्यग्रहणाद्बोध्या ॥ वस्तुत एषां धातुत्वे फलाभावः । न च प्रातिपदिकत्वाभावः फलम् । कृदन्तत्वेन तदभावस्य वक्तुमशक्यत्वात् । उभयोः सत्त्वेपि लिडिलादाविव परत्वात्सुपामेवोत्पत्तिसिद्धेः । वार्तिके प्रातिपदिकग्रहणं तु प्रौढ्यैव । अत एव तदुदाहरणानुक्तिर्भाष्ये ॥

(८२३ पाठप्रयोजनान्तरवार्तिकम् ॥ १८ ॥)

॥ * ॥ स्वरानुबन्धज्ञापनाय च ॥ * ॥

(भाष्यम्) स्वरानुबन्धज्ञापनाय च पाठः कर्तव्यः । स्वराननुबन्धांश्च ज्ञास्यामीति । नह्यन्तरेण पाठं स्वरा अनुबन्धा वा शक्या विज्ञातुम् ॥

(प्रत्याख्यानभाष्यम्)

ये त्वेते न्याय्यविकरणा उदात्ता अननुबन्धकाः पठ्यन्ते तेषां पाठः शक्योऽकर्तुम् ॥

(आक्षेपभाष्यम्)

एतेषामप्यवश्यमाणवयत्यादिनिवृत्त्यर्थः पाठः कर्तव्यः ।

(प्रदीपः) एतेषामपीति । तेषामपाठे निवृत्तिराणवयत्यादिवत्स्यात्तस्मादाणवयत्यादिष्वेषां निवृत्तिर्यथा स्यात् तन्मध्ये मा प्रविक्षन्नित्येवमर्थस्तेषामपि पाठः कर्तव्य इत्यर्थः ।

(उद्योतः) ननु तेषां संज्ञार्थः पाठः कर्तव्य इति वक्तव्ये आणवयत्यादिनिवृत्त्यर्थं इत्यसङ्गतमत आह—तेषामिति । पाठाभावे हि तेपि आणवयत्यादिवन्निवृत्तिर्भवेयुरिति । आणवयत्यादिभ्यो निवृत्त्यर्थो भेदार्थ इति भाष्यार्थ इति भावः ॥

(प्रत्याख्यानसाधकभाष्यम्)

न कर्तव्यः ।

(८२४ कारणवार्तिकम् ॥ १९ ॥)

॥ * ॥ शिष्टप्रयोगादाणवयत्यादीनां निवृत्तिः ॥ * ॥

(भाष्यम्) शिष्टप्रयोगादाणवयत्यादीनां निवृत्तिर्भविष्यति । स चावश्यं शिष्टप्रयोग उपास्यः । येपि पठ्यन्ते तेषामपि विपर्यासनिवृत्त्यर्थः । लोके हि कृञ्यर्थे कसिं प्रयुञ्जते, दृश्यर्थे च दिसिम् ॥

भूवादयो धातवः ॥ १ ॥

(प्रदीपः) शिष्टप्रयोगादिति । प्रयुक्तानामिदमन्वाख्यानम्, न चाणवयत्यादयः शिष्टैः प्रयुज्यन्ते इति नास्ति तेषां शास्त्रेणानुविधानमिति भावः । एतेनैव न्यायेन प्रातिपदिकनिवृत्त्यर्थोपि पाठो नोपयुज्यते । नहि पाकादयः शब्दाः धातुविहितप्रत्ययपरा लोके प्रयुज्यन्ते ॥ १ ॥

(उद्द्योतः) प्रयुक्तानामिति। प्रयुक्तानां च संप्रत्यदृश्यमानपाठानामपि भविष्यतीत्यपि बोध्यम् ॥ नन्वेवमपि प्रातिपदिकनिवृत्त्यर्थः पाठः स्यादत आह—एतेनेति। इदमुपलक्षणम्। स्वरानुबन्धकार्यमपि शिष्टप्रयोगादेवेति बोध्यम् ॥ ननु शिष्टप्रयोगालम्बनेन प्रत्याख्याने शास्त्रवैफल्यमत आह—भाष्ये—स चावश्यमिति। एवं चाकृतिगणेष्विव तदुपासनावश्यकत्वे किं पाठेनेति भावः ॥ ननु तद्वदेव निदर्शनार्थं कतिपयपाठोऽप्यावश्यक इति चेत्। अस्तु, अत्यन्तावश्यकता नेत्येव भाष्यतात्पर्यादिति दिक् ॥ १ ॥

(अथेत्संज्ञाप्रकरणम्)

(१२३ अचामित्संज्ञासूत्रम् ॥ । १ । ३ । १ आ. २ सू.)

१४९ उपदेशेऽजनुनासिक इत् १।३।२॥

(उद्देशोपदेशपदार्थकथनाधिकरणम्)

(आक्षेपभाष्यम्)

उपदेश इति किमर्थम्? ॥

(प्रदीपः) उपदेशे ॥ २ ॥ उद्देशोपदेशशब्दयोरुपसर्गभेदेपि अभिन्नार्थत्वं प्रक्रमत उपक्रमते इत्येतयोरिव मन्यमानः पृच्छति—उपदेश इति किमर्थमिति ॥

(उद्द्योतः) उपदेशेऽज ॥२॥ ननूपसर्गभेदेऽर्थभेदस्यावश्यकत्वात्प्रश्नानुपपत्तिरत आह—उपदेशेति। उभावपि धात्वर्थानुवादकावेवेति भावः ॥ येन निष्ठेत्यादिविहितानां संग्रह आङश्च व्यावृत्तिः, स विशेषः क इति प्रश्नार्थ इत्यन्ये ॥

(समाधानभाष्यम्)

अभ्रआँ अपः। उद्देशे योऽनुनासिकस्तस्य मा भूदिति ॥

(प्रदीपः) अभ्रआँ अप इति। अयं नोपदिष्टः किं तर्हि आङोऽनुनासिकश्छन्दसीति लक्षणेनान्तरतम आङः स्थाने विहितः। यदि तु 'आङ आँ छन्दसि' इत्यवक्ष्यत्तदाऽभविष्यदेषोऽप्युपदेशेऽनुनासिकः ॥

(उद्द्योतः) नन्वाङोनुनेत्यप्युपदेश एवेत्यत आह—अयमिति ॥ उच्चारणेन बोधनाभावादित्यर्थः ॥ ननु नास्योद्देशत्वमपि, अङ्गदीत्यादिवद् बहुभिर्गुणैः प्रापणं हि तत्। नेह तथा, अनुनासिकत्वेनैव प्रापणादत आह—अन्तरतम इति। तथा च कण्ठ्यत्वदीर्घत्वादिभिरपि प्रापणान्न दोषः ॥ गुणैरित्यत्र बहुत्वमविवक्षितमिति तत्त्वम् ॥

(आक्षेपभाष्यम्)

कः पुनरुद्देशोपदेशयोर्विशेषः? ॥

(समाधानभाष्यम्)

प्रत्यक्षमाख्यानमुपदेशः। गुणैः प्रापणमुद्देशः ॥ प्रत्यक्षं तावदाख्यानमुपदेशः। तद्यथा—अगोज्ञाय कश्चिद्गां सक्थनि कर्णे वा गृहीत्वा उपदिशति—'अयं गौः' इति। स प्रत्यक्षमाख्यातमाह—'उपदिष्टो मे गौः' इति ॥ गुणैः प्रापणमुद्देशः। तद्यथा—कश्चित्कंचिदाह—'देवदत्तं मे भवानुद्दिशतु' इति। स इहस्थः पाटलिपुत्रस्थं देवदत्तमुद्दिशति 'अङ्गदी कुण्डली किरीटी व्यूढोरस्को वृत्तबाहुर्लोहिताक्षस्तुङ्गनासो विचित्राभरण ईदृशो देवदत्तः' इति। स गुणैः प्राप्यमाणमाह—'उद्दिष्टो मे देवदत्तः' इति ॥

(प्रदीपः) प्रत्यक्षमाख्यानमिति। इन्द्रियगोचरार्थस्य यदाख्यानं स उपदेश इत्यर्थः। प्रसिद्धधर्मोपादानेन तु यत्प्रतिपादनं स उद्देशः। प्रत्यक्षमाख्यातमिति क्वचित्पाठः। तत्राख्यानमाख्यातमिति भावे क्तो विज्ञेयः ॥ ईदृश इति। एतैः शब्दैः यादृशो बुद्धावर्थः प्रतिभासते तादृशो बाह्य इत्यर्थः ॥

(उद्द्योतः) आख्याने प्रत्यक्षत्वमविशिष्टमत आह—इन्द्रियेति। यद्यप्यनुनासिकत्वमपीन्द्रियग्राह्यं, तथाप्यनुनासिकशब्दप्रतिपाद्यतावेलायामिन्द्रियागोचरमिति भावः ॥ प्रसिद्धेति। प्रत्येकसाधारणेत्यपि बोध्यम् ॥ भाष्ये—आख्यातमाहेति। कथितमित्यर्थः ॥ एकव्यक्तौ भेदाभावादीदृश इत्यसंगतमत आह—एतैरिति ॥ बाह्य इति। लोके दृश्यमान इत्यर्थः। एतेन बौद्धार्थस्यैव शाब्दबोधे भानमिति दर्शितम् ॥

(८२५ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ इत्संज्ञायां सर्वप्रसङ्गोऽविशेषात् ॥ * ॥

(भाष्यम्) इत्संज्ञायां सर्वप्रसङ्गः। सर्वस्यानुनासिकस्येत्संज्ञा प्राप्नोति। अस्यापि प्राप्नोति—अभ्रआँ अपः ॥ किं कारणम्? ॥ अविशेषात्। नहि कश्चिद्विशेष उपादीयते—एवंजातीयकस्यानुनासिकस्येत्संज्ञा भवतीति। अनुपादीयमाने विशेषे सर्वप्रसङ्गः ॥

(उद्द्योतः) इत्संज्ञायामिति। उक्तविशेषस्य निष्ठायसंग्रहेणाश्रयणमशक्यमिति भावः ॥

(आक्षेपबाधकभाष्यम्)

किमुच्यते—अनुपादीयमाने विशेष इति ॥ कथं न नामोपादीयते यदोपदेश इत्युच्यते? ॥

(आक्षेपसाधकभाष्यम्)

लक्षणेनापि ह्युपदेशः। संकीर्णावुद्देशोपदेशौ। प्रत्यक्षमप्याख्यानमुद्देशः' गुणैश्च प्रापणमुपदेशः।

प्रत्यक्षं तावदाख्यानमुद्देशः। तद्यथा—कश्चित्कंचिदाह—'अनुवाकं मे भवानुद्दिशतु' इति। स तस्मायाचष्टे—'इषेत्वकमधीष्व' 'शंनोदेवीयकमधीष्व' इति। स प्रत्यक्षमाख्यातमाह—'उद्दिष्टो मेऽनुवाकस्तमध्येष्ये' इति॥ गुणैश्च प्रापणमुपदेशः। तद्यथा—कश्चित्कंचिदाह—'ग्रामान्तरं गमिष्यामि पन्थानं मे भवानुपदिशतु' इति। स तस्मायाचष्टे—'अमुष्मिन्नवकाशे हस्तदक्षिणो ग्रहीतव्यः, अमुष्मिन्हस्तवामः' इति। स गुणैः प्राप्यमाणमाह—'उपदिष्टो मे पन्थाः' इति। एवमेतौ संकीर्णावुद्देशोपदेशौ॥

(प्रदीपः) लक्षणेनेति। लक्ष्यतेऽनेनेति लक्षणं गुणस्तेनाप्युपदेशो भवतीत्यर्थः॥ इषेत्वकमधीष्वेति। इषेत्वकमित्येतत् पूर्वेण संबध्यते स तस्मायाचष्टे इषेत्वकमिति। इषेत्वाशब्दो यस्मिन्ननुवाकेऽस्ति तमाचष्टे इत्यर्थः। गोषदादिभ्यो वुन्निति वुन्प्रत्ययः॥ किमर्थमाचष्ट इत्याह—अधीष्वेति। अध्ययनार्थमाचष्ट इत्यर्थः॥

(उद्द्योतः) ननु हस्तदक्षिणत्वादिकं नेतरभेदानुमापकं लक्षणमत आह—गुणस्तेनापीति। भाष्ये हिरण्यर्थ इति भावः॥ क्वचित्तु लक्षणेनापि हीति पाठः॥ बहुत्वं चाविवक्षितमेव। प्रकृतसूत्रे चास्यापि ग्रहणमत एव निष्ठेत्यादिभिः संज्ञया विहितप्रत्ययावयवानामित्संज्ञासिद्धिरिति भावः। अत एवात्रैतत्कथनं सफलम्॥ आदेच इत्यादौ तु व्याख्यानात्प्रत्यक्षमाख्यातमुपदेश इत्यस्यैव ग्रहणमिति बोध्यम्॥ उपदेश इति। अज्ञातज्ञापनं भवतीत्यर्थः॥ आचष्टे इत्यस्य कर्माकाङ्क्षत्वादाह—पूर्वेणेति। अध्ययनार्थमिति। इतिर्हेतौ। फलं च हेतुरिति भावः। इषेत्वकमधीष्वेत्यादिवाक्यमाचष्ट इत्यन्वय इत्यन्ये॥

(आक्षेपबाधकभाष्यम्)

एवं तर्हीत्कार्याभावादत्रेत्संज्ञा न भविष्यति॥

(आक्षेपसाधकभाष्यम्)

ननु च लोप एवेत्कार्यं स्यात्॥

(आक्षेपबाधकभाष्यम्)

अकार्यं लोपः॥ इह हि शब्दस्य द्व्यर्थ उपदेशः। कार्यार्थो भवत्युपदेशः श्रवणार्थो वा। कार्यं चेह नास्ति। कार्ये चासति यदि श्रवणमपि न स्यादुपदेशोऽनर्थकः स्यात्॥

(प्रदीपः) अकार्यं लोप इति। यदि लोपोभिमतोऽभविष्यदाङो लोपश्छन्दसीत्येवावक्ष्यदित्यर्थः॥

(उद्द्योतः) नन्वित्कार्ये तदकार्यत्ववादोऽयुक्तोऽत आह—यदीति। अभिमतकार्यत्वाभावपरोऽकार्यशब्द इत्यर्थः॥

(आक्षेपसाधकभाष्यम्)

इदमस्तीत्कार्यम्—'इह अभ्र आँ अटितः' अनन्तरलक्षणायां सत्यामित्संज्ञायाम् "आदितश्च" इतीट्प्रतिषेधः प्रसज्येत॥

(प्रदीपः) अनन्तरलक्षणायामिति। यदा अनेकान्ता अनुबन्धास्तदा अनन्तर इत्संज्ञकः कार्यस्य विशेषको भवतीति धातोरादित्त्वादिट्प्रतिषेधप्रसङ्गः॥

(उद्द्योतः) नन्वित्संज्ञाया आनन्तर्यनिमित्तकत्वाभावेनानन्तरलक्षणायामित्यसंगतमत आह—यदेति। अनन्तरलक्षणायामित्यस्यानन्तरलक्षणकार्यायामित्यर्थः। शिदित्यादावनन्तरादिषु वृत्त्यभावेपि सौत्रत्वाद्वृत्तिरिति भावः॥ ननु तत्रेत्त्वे आङ इदित्येवावक्ष्यदिति चेन्न। विधानसामर्थ्याल्लोपो मा भूत्संज्ञा तु स्यादेवेति भाष्याशयः॥ एवं चात्रोपदेशग्रहणं प्रत्याख्यातम्। अनुबन्धा एकान्ता इत्यस्यैव न्याय्यताया वक्ष्यमाणत्वात्॥

(८२६ एकदेशिसमाधानवार्तिकम्॥ २॥)

॥ * ॥ सिद्धं तूपदेशनेऽनुनासिकवचनात्॥ * ॥

(भाष्यम्) सिद्धमेतत्। कथम्?। उपदेशने योऽनुनासिकः स इत्संज्ञो भवतीति वक्तव्यम्॥ किं पुनरुपदेशनम्?। शास्त्रम्॥

(प्रदीपः) उपदेशन इति। तेन शास्त्रे य उच्चारितोऽनुनासिकः स इत्संज्ञ इत्यर्थः॥

(उद्द्योतः) अभ्रआं इत्यस्यापि शास्त्रे विहितानुनासिकत्वादाह—शास्त्रे य उच्चारित इति। उच्चारित इत्यध्याहार इति भावः॥ भाष्ये—शास्त्रमिति। तत्र धात्वादिरूपं बोध्यम्। आदेच उपदेश इत्यादाविव भावसाधनस्याद्योच्चारणरूपार्थकस्य ग्रहणे तु लटः सद्वा निष्ठेतिविहितशत्राद्यवयवस्येत्संज्ञानापत्तिः। यथा कथंचिद्बोधनस्योपदेशत्वे त्वभ्रआमित्यादौ दोष इति भावः॥ तदाह—घञयं करणेति॥

(आक्षेपभाष्यम्)

सिध्यति। सूत्रं तर्हि भिद्यते॥

(सिद्धान्तिसमाधानभाष्यम्)

यथान्यासमेवास्तु॥

(आक्षेपस्मारणभाष्यम्)

ननु चोक्तम्—"*इत्संज्ञायां सर्वप्रसङ्गोऽविशेषात्*" इति॥

(समाधानभाष्यम्)

नैष दोषः। उपदेश इति घञयं करणसाधनः॥

(समाधानबाधकभाष्यम्)

न सिध्यति। परत्वाद्युट् प्राप्नोति॥

(प्रदीपः) परत्वादिति । परत्वेन बाधकत्वं लक्ष्यते । तेनानवकाशत्वाल्ल्युट् प्राप्नोतीत्यर्थः ॥

(उद्द्योतः)उत्सर्गापवादयोर्विप्रतिषेधायोगादाह—परत्वेनेति॥

(समाधानसाधकभाष्यम्)

न ब्रूमः—"अकर्तरि च कारके संज्ञायाम्" इति॥ किं तर्हि? ॥ "हलश्च" इति ॥

(प्रदीपः) हलश्चेति । अयं तु ल्युटो बाधको घञ् ॥

(समाधानबाधकभाष्यम्)

तत्रापि संज्ञायामिति वर्तते, न चैषा संज्ञा ॥

(समाधानसाधकभाष्यम्)

प्रायवचनादसंज्ञायामपि भविष्यति ॥

(प्रदीपः) प्रायवचनादिति । हलश्चेत्यत्र संज्ञायां प्रायेणेति चानुवर्तते । संज्ञया च प्रायग्रहणमभिसंबध्यते प्रायेण संज्ञायां घञ् भवति क्वचिदसंज्ञायामपीत्यर्थः ॥

(समाधानबाधकभाष्यम्)

प्रायवचनात्संज्ञायामेव स्याद्वा न वा ॥ नह्युपाधेरुपाधिर्भवति विशेषणस्य वा विशेषणम् ॥

(प्रदीपः) संज्ञायामेवेति । प्रत्ययस्य विधेयत्वात्प्राधान्यात्प्रायग्रहणं प्रत्ययेनैव संबध्यते, न तु गुणेन संज्ञयेत्यर्थः । उपाधिविशेषणयोश्च वाच्यत्वावाच्यत्वाभ्यां विशेषः । तथाहि दृतिहरिरिति प्रत्ययेन पशुः कर्ताभिधीयते इति पशुरुपाधिः । गार्गिकया श्लाघत इति श्लाघा वुञा नाभिधीयत इति विशेषणमुच्यते ॥

(उद्द्योतः) पशुः कर्त्ताभिधीयते इति । यद्यपि कर्तृत्वेनैव कर्त्ता प्रत्ययार्थस्तथापि तत्त्वेनापि पशुरेवाभिधीयत इति स उपाधिरित्यर्थः । श्लाघेति । गोत्रचरणाद्भावे वुञ् स चेत् श्लाघादिभिरन्वितः स्यादिति सूत्रार्थात् । श्लाघादिकं न प्रत्ययेन स्पृश्यत इति भावः ॥

(हेतुबाधकभाष्यम्)

यदि नोपाधेरुपाधिर्भवति विशेषणस्य वा विशेषणम् । "कल्याण्यादीनामिनङ्, कुलटाया वा" इनङ्विभाषा न प्राप्नोति ॥

(प्रदीपः) इनङ् विभाषेति । प्रत्ययस्य विधेयतया प्राधान्यात्तादर्थ्येन प्रकृतेर्गुणत्वात्तदादेशस्येनङोपि गुणत्वादुपाधित्वमित्यर्थः ॥

(उद्द्योतः) नन्विनङोपि विधेयतया प्राधान्यात्कथं गुणत्वमत आह—प्रत्ययस्येति । आर्थिकं गुणत्वमस्तीत्यभिमानः ॥

(हेतुसाधकभाष्यम्)

इनङेवात्र प्रधानम् । विहितः प्रत्ययः प्रकृतश्चानुवर्तते ॥

(प्रदीपः) इनङेवात्रेति ॥ अपूर्वोपदेशात्तस्यैव प्राधान्यमित्यर्थः । ढक्तु स्त्रीभ्यो ढगित्येव सिद्धः । तदनुवादेनेनङ् विधीयते ॥

(उद्द्योतः) ननु प्रत्ययस्याविधेयत्वाद्गुणत्वमित्ययुक्तम् । अनुवाद्यत्वस्य प्राधान्यनियतत्वाद्विधेयत्वस्य गुणत्वनियतत्वादिति मीमांसकशङ्कां परिहरति—अपूर्वेति । न मीमांसकसंमते प्राधान्यगुणत्वे भगवतोभिमते किं तु शास्त्रसंरम्भगोचरत्वतदगोचरत्वे एवेति भावः ॥

(हेतुबाधकान्तरभाष्यम्)

इह तर्हि "वाकिनादीनां कुक् च, पुत्रान्तादन्यतरस्याम्" इति कुग् विभाषा न प्राप्नोति ॥

(हेतुसाधकभाष्यम्)

अत्रापि कुगेव प्रधानम् । विहितः प्रत्ययः प्रकृतश्चानुवर्तते ॥

(प्रदीपः) कुगेवेति । उदीचां वृद्धादगोत्रादित्यनेन फिञ् विहितस्तदनुवादेन कुको विधानात् ॥

(उद्द्योतः) ननु वाकिनादीनामित्यतश्चकारानुवृत्त्या तद्वेवानेन प्रत्ययस्यापि विधेयत्वमेवेत्यत आह—उदीचामिति । नात्र चोनुवर्त्तत इति भावः ॥

(आक्षेपोपसंहारभाष्यम्)

एवं न चेदमकृतं भवति—'नोपाधेरुपाधिर्विशेषणस्य वा विशेषणम्' इति । न च कश्चिद्दोषो भवति । एवं च कृत्वा घञ् न प्राप्नोति ॥

(प्रदीपः) न चेदमकृतमिति । आश्रितमेवेत्यर्थः । गुणप्रधानसन्निधौ यत्र प्रधानमर्थि विशेषणेन भवति तत्र तस्यैव विशेषणं न्याय्यं न तु गुणस्य ॥ एवं च कृत्वेति । एवं स्थितेत्यर्थः । तेन घञेव न्यायवशात्संज्ञायां प्रायेण तिष्ठति स एवात्र न प्राप्नोतीति समानकर्तृकत्वात् क्त्वाप्रत्यय उपपद्यते ॥

(उद्द्योतः) ननु गुणः कृतात्मसंस्कार इतिन्यायेन गुणस्यापि विशेषणसंबन्धदर्शनादाह—गुणप्रधानसन्निधौ यत्रेति । तद्भिन्नविषयः स न्याय इति भावः ॥ ननु कृत्वेति कृञर्थो विचारस्तत्र पुरुषः कर्ता, प्राप्तौ घञित्यसमानकर्तृकत्वात् क्त्वा न प्राप्नोतीत्यत आह—एवं स्थित्वेति ॥ २ ॥

(सिद्धान्तिसमाधानभाष्यम्)

एवं तर्हि "कृत्यल्युटो बहुलम्" इत्येवमत्र घञ् भविष्यति॥ उपदेशेजनुनासिक इत् ॥ २ ॥

(प्रदीपः) एवं तर्हीति । बहुलग्रहणादसंज्ञायामपि घञ् भविष्यतीत्यर्थः ॥ २ ॥

(१२४ इत्संज्ञासूत्रम् १। ३ । १ आ. ३ सू.)

१५० हलन्त्यम् १।३।३ ॥

(अनिष्टवारणाधिकरणम्)

(८२७ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ हलन्त्ये सर्वप्रसङ्गः सर्वान्त्यत्वात् ॥ * ॥

(भाष्यम्) **हलन्त्ये सर्वप्रसङ्गः । सर्वस्य हल इत्संज्ञा प्राप्नोति ॥ किं कारणम् ?। सर्वान्त्यत्वात् । सर्वो हि हल् तं तमवधिं प्रत्यन्तो भवति ॥**

(प्रदीपः) **हलन्त्यम्** ॥३॥ अन्तेऽवसाने भवमन्त्यम् ॥ **सर्वो हि हलिति** । सर्वस्य हलोऽवसानेन सम्बन्धात् । अन्त्यग्रहणं त्वादिनिवृत्त्यर्थं स्यात् ॥

(उद्द्योतः) **हलन्त्यम्** ॥ ३ ॥ अन्तशब्दो नान्तावयववाची तद्धितवैयर्थ्यापत्तेः । नापि समीपपरोऽतिप्रसङ्गादत आह—**अवसाने इति** ॥ ननु यदुच्चार्य विरम्यते तस्यैवान्त्यत्वम्, न च तन्मध्यगतस्येति कथं सर्वप्रसङ्गोऽत आह—**सर्वस्येति** । सर्वमपि वर्णमुच्चार्य विरम्यत एव । स्पष्टं चेदं **परः सन्निकर्षः** इति सूत्रे भाष्ये । न च ततः परमुच्चारणाभावोऽप्यपेक्षित इति भावः ॥ भाष्ये **सर्वो हि हलन्त्यो** भवतीत्येव पाठः । **तं तमवधिं प्रतीति** पाठे तत्तद्वर्णोच्चारणानन्तरभाविविरामरूपमवधिं प्रतीत्यर्थः । **तं तमवधीकृत्येति** पाठान्तरम् ॥ नन्वेवमन्त्यग्रहणं व्यर्थमत आह—**आदिनिवृत्त्यर्थमिति** । उपक्रमाभावलक्षकं तदिति भावः । न च पूर्वसूत्रे उपदेशशब्दस्य धात्वादिशास्त्रपरतया तस्यैव प्रकृतेऽनुवृत्त्या यत्किञ्चित्समुदायान्त्यवारणेन शङ्कैवाऽनुपपन्नेति वाच्यम् । तस्य स्वरितत्वाभाव इत्याशयात् ॥

(८२८ समाधानवार्तिकम् ॥ २ ॥)

॥ * ॥ सिद्धं तु व्यवसितान्त्यत्वात् ॥ * ॥

(भाष्यम्) **सिद्धमेतत् । कथम् ?। व्यवसितान्त्यत्वात् । व्यवसितान्त्यो हलित्संज्ञो भवतीति वक्तव्यम् ॥ के पुनर्व्यवसिताः ? । धातुप्रातिपदिकप्रत्ययनिपातागमादेशाः ॥**

(प्रदीपः) **सिद्धं त्विति** । व्यवसिताः परिच्छिन्ना ये समुदायाः धातुत्वप्रत्ययत्वादिना धर्मेण तेषां योऽन्त्य इत्यर्थः । अवयवास्तु समुदायतन्त्रत्वान्नान्तरीयकोपदेशत्वाद्धातुत्वादिना न परिच्छिन्नाः ॥

(उद्द्योतः) व्यवसितपदस्य निश्चितपरत्वभ्रमं वारयति—**व्यवसिता इति** । शास्त्रकृता परिच्छिन्नत्वेन बोधिता इत्यर्थः ॥ धात्वित्यादि ॥ वक्ष्यमाणेत्यादिः ॥ अवयवानां धातुत्वाभावे युक्तिमाह—**अवयवा इति** ॥ **समुदायतन्त्रत्वात्** । समुदायस्तन्त्रं प्रयोजनं येषां तस्मात् ॥ भाष्ये—**धातुप्रातिपदिकेति** । अरुण् नदट् इत्यादौ ण् टादीनामित्संज्ञा क्रमबोधकत्वेन स्वरूपबोधकत्वेन च प्रातिपदिकत्वात् । श्रोत्रियनादेरपि तत्त्वादेव ॥ निपातोदाहरणमाङादि ॥

(आक्षेपभाष्यम्)

सिध्यति । सूत्रं तर्हि भिद्यते ॥

(सिद्धान्तिसमाधानभाष्यम्)

यथान्यासमेवास्तु ॥

(आक्षेपस्मारणभाष्यम्)

ननु चोक्तम्—'*हलन्त्ये सर्वप्रसङ्गः सर्वान्त्यत्वाद् *' इति ॥

(समाधानभाष्यम्)

नैष दोषः । आहायम्—हलन्त्यमित्संज्ञं भवतीति । सर्वश्च हल् तं तमवधिं प्रत्यन्त्यो भवति । तत्र प्रकर्षगतिर्विज्ञास्यते—साधीयो योऽन्त्य इति ॥ कश्च साधीयः ?। व्यवसितानां योऽन्त्यः ॥ अथ वा सापेक्षोऽयं निर्देशः क्रियते । न चान्यत्किंचिदपेक्ष्यमस्ति, तेन व्यवसितानेवापेक्षिष्यामहे ॥

(प्रदीपः) **तत्र प्रकर्षगतिरिति** । आदिनिवृत्त्यर्थत्वादन्त्यशब्दस्य कथं प्रकर्षगतिः ॥ उच्यते—आदेरप्युच्चारणानन्तरमवसानसम्बन्धादन्त्यत्वमनिवार्यमिति नास्ति तन्निवृत्तिरिति सामर्थ्यात्प्रकर्ष आश्रीयते ॥ **व्यवसितानां योऽन्त्य इति** । आदिमध्यानां च काल्पनिकमन्त्यत्वं सर्वान्त्यस्य तु नित्यमेवेति तस्यैव युक्तं ग्रहणम् ॥ **अथ वेति** । पूर्वं समुदायावयवसन्निधौ समुदायापेक्षमन्त्यत्वमाश्रयितुं युक्तमिति परिहृतम् ॥ इदानीं तु समुदायार्थत्वादुपदेशस्यावयवानामसत्त्वात्तदपेक्षणं दूरोत्सारितमिति मत्वा परिह्रियते ॥

(उद्द्योतः) **सामर्थ्यादिति** । लक्षणां विनैवोपपत्तावुपक्रमाभावलक्षकत्वमेव दोष इति भावः ॥ **काल्पनिकमिति** । सर्वान्त्यस्य हि मुख्यं तत् यस्मात्परो नास्तीत्यादिलक्षणाक्रान्तत्वादिति भावः ॥ **अवयवानामसत्त्वादिति** । तत्प्रतीतिस्तु भ्रम एव । तन्मूलक एव च समुदायव्यवहार इति भावः ॥

(अन्योन्याश्रयदोषपरिहाराधिकरणम्)

(८२९ आक्षेपवार्तिकम् ॥ ३ ॥)

॥ * ॥ लकारस्यानुबन्धाज्ञापितत्वाद्धल्ग्रहणाप्रसिद्धिः ॥ * ॥

(भाष्यम्) **लकारस्यानुबन्धत्वेन अज्ञापितत्वाद्धल्ग्रहणस्याप्रसिद्धिः । हलन्त्यमित्संज्ञं भवतीत्युच्यते । लकारस्यैव तावदित्संज्ञा न प्राप्नोति ॥**

(प्रदीपः) **लकारस्येति** । इतरेतराश्रयं मन्यते । शषसर् हल् इत्यत्र लकारस्य सत्यामित्संज्ञायां हलिति प्रत्याहारः । सति च प्रत्याहारे लणित्यत्र लकारस्य हल्त्वात्तस्यैव

शापसर् हलिल्यत्रान्ते निर्दिष्टत्वादित्संज्ञेति प्रत्याहाराश्रया इत्संज्ञा, तदाश्रयश्च प्रत्याहारः ॥

(उद्योतः) ननु हलामित्संज्ञाविधाने लकारे तदप्राप्तिः कथमत आह—**इतरेतरेति** ॥

(८३० समाधानवार्तिकम् ॥ ४ ॥)

॥ * ॥ सिद्धं तु लकारनिर्देशात् ॥ * ॥

(भाष्यम्) **सिद्धमेतत् । कथम् ? । लकारनिर्देशः कर्तव्यः । हलन्त्यमित्संज्ञं भवति "लकारश्च" इति वक्तव्यम् ॥**

(प्रदीपः) **लकारश्चेति** । पूर्वं लकारस्येत्संज्ञा विधेया तेन हलिति प्रत्याहार उपपद्यते । तत्र हल् च ल् चेति समाहारद्वन्द्वं कृत्वा **संयोगान्तस्य लोप** इति लकारो लुप्यते ॥

(उद्योतः) भाष्ये **हलन्त्यमित्युत्तरं लश्चेति** वाक्यान्तरकरणात्तदर्थबोध्यात्पूर्वं कथं तस्य बोधोऽत आह—**पूर्वमिति** । पाठक्रमादार्थक्रमो बलीयानिति भावः ॥ इतरेतरयोगे द्विवचनापत्तेराह—**समाहारे इति** ॥ एवं च भाष्ये कर्तव्यपदं व्याख्येयपरमिति भावः ॥ वस्तुतो भाष्ये कर्तव्यपदं यथाश्रुतमेव ॥ कैयटस्तु चिन्त्यः । यँणः प्रतिषेधारम्भेण झल्ग्रहणापकर्षेण च संयोगान्तलोपाप्राप्तेः । वक्तृणां सह बोधासंभवेन नाज्झलाविति सूत्रोक्तवाक्यापरिसमाप्तिन्यायेन भाविसंज्ञया पूर्वमाचार्याणामव्यवहारेण च सहविवक्षाभावाद् द्वन्द्वाप्राप्तेश्चेति बोध्यम् । अत एव भाष्ये **निर्देशः कर्तव्य** इत्युक्तम् । निर्देश उच्चारणम् । न तु लुप्तनिर्दिष्ट इत्युक्तम् ॥ एतेन हलन्त्यं ल इति प्रश्लेषः । सौत्रश्च तस्य लोप इत्यपास्तम् । सौत्रत्वाल्लोपं कृत्वा व्याख्यानमाश्रयणीयमिति गौरवेण भाष्यकृद्वक्ष्यमाणरीत्यैव प्रत्याख्यानस्य न्याय्यत्वात् ॥

(८३१ समाधानान्तरवार्तिकम् ॥ ५ ॥)

॥ * ॥ एकशेषनिर्देशाद्वा ॥ * ॥

(भाष्यम्) **अथ वा एकशेषनिर्देशोयम् । हल् च हल् च हल् हलन्त्यमित्संज्ञं भवतीति ॥**

(प्रदीपः) **हल् चेति** । हस्य ल् हल् । हल् इत्येकः षष्ठीतत्पुरुषः । द्वितीयः प्रत्याहारः । **नपुंसकमनपुंसकेनेति** चैकशेषः । एकस्य पुल्लिङ्गत्वादितरस्य नपुंसकत्वात् ॥

(उद्योतः) **हस्यलिति** । संबन्धसामान्यषष्ठ्या समासे पर्यवसानगत्या सामीप्यलाभ इति भावः ॥ **इतरस्येति** । प्रकृतेन्त्यपदसामानाधिकरण्यादिति भावः ॥ वस्तुत इदं चिन्त्यम् । एवमर्थस्येष्टत्वे तत्पुरुषेन्त्यपदासंबन्धेन हलित्संज्ञं हलन्त्यं चेत्संज्ञमिति वदेत् पूर्ववत् । तस्माद्वाक्यद्वयमप्यन्त्यपदघटितम् द्वन्द्वान्ते श्रूयमाणस्यैव प्रत्येकं संबन्धात् । तयोश्च तन्त्रेणोच्चारणं भाष्य इति हलसूत्रान्त्यमन्त्यं च हलिदित्येव भाष्यार्थः ॥ एकशेपशब्देन च भाष्ये तन्त्रं लक्ष्यते । अन्यथा सहविवक्षाभावादेकशेषः शास्त्रीयो न स्यादिति बोध्यम् ॥

(एकदेशिसमाधानान्तरभाष्यम्)

अथ वा लकारस्यैवेदं गुणभूतस्य ग्रहणम् । तत्र "उपदेशेऽजनुनासिक इत्" इतीत्संज्ञाभविष्यति ॥

(प्रदीपः) **अथ वेति । शापसर् हलिल्यत्र हलन्त्य**मित्यत्र च लकारस्यैकादेशो लपरत्वं च क्रियते ॥ नन्वेवमपीतरेतराश्रयमेव । लकारस्य सत्यामित्संज्ञायां हलिति प्रत्याहारः, सति च प्रत्याहारे **ऐऔजिति** चकारस्येत्संज्ञा, तस्यां सत्यामजिति प्रत्याहारः, अजिति प्रत्याहारे सति लकारस्येत्संज्ञा ॥ एवं तर्हि **लृदित** इति ज्ञापकात् लकारस्येत्संज्ञाकार्यं भविष्यतीति नास्तीतरेतराश्रयमिति भगवतो भाष्यकारस्याभिप्रायः ॥

(उद्योतः) भाष्ये एकदेश्याह—**अथ वेत्यादि** । ज्ञापकेन लकारस्येत्त्वे **उपदेश** इतिसूत्रोल्लेखोऽसंगत इत्यत आह—**लकारस्येत्संज्ञाकार्यमिति** । अचूपदघटितसूत्रस्य कार्यभूतेत्संज्ञेत्यर्थः ॥

(एकदेशिसमाधानान्तरभाष्यम्)

अथ वा आचार्यप्रवृत्तिर्ज्ञापयति—भवति लकारस्य इत्संज्ञेति । यदयं णलं लितं करोति ॥

(प्रदीपः) **अथ वेति** । णलो लकारः स्वरार्थः कृतः, असत्यां चेत्संज्ञायां कुतः स्वरः । श्रवणार्थस्तु णलो न लकारः, **हलङ्याब्भ्यो**विति सूत्रे हल्ग्रहणाण्णल्व्यावृत्त्यर्थात् । तत्र हि विभेदेति णल्व्यावृत्त्यर्थं हल्ग्रहणं कृतम् । लकारस्य श्रवणेऽपृक्तत्वाभावाल्लोपस्याप्राप्तिरिति किं हल्ग्रहणेन ॥

(उद्योतः) **हल्ग्रहणादिति** । न च ङानिवृत्त्यर्थं तत् । सुतिसीतिप्रत्ययैः प्रकृत्याक्षेपेण तद्व्यावृत्तिसिद्धिरित्यभिमानः । वस्तुतस्तद्बिभेदेत्यादिनिर्देशान्न श्रवणार्थो लकार इति भाष्यतात्पर्यम् । अनयोरेकदेश्युक्तित्वं तु लकारेत्संज्ञाया अपि हल्पदार्थसिद्धेः प्रागलाभात् । लृदित इति ज्ञापकमपि शिथिलम् । सर्वेषामच्चामित्संज्ञाकाले तस्यापीत्त्वलाभात् ॥ एवं णलो लित्वस्यापि ज्ञापकतोक्तिश्चादीनामित्संज्ञाप्रवृत्तिकाले णलो लस्यापि तत्प्रवृत्त्या ज्ञापकासंभवात् । तस्माद् * **एकशेषनिर्देशाद्वा** * इत्येव समाधानम् ॥

(अनिष्टप्रातिपदिकत्संज्ञावारणाधिकरणम्)

(८३२ आक्षेपवार्तिकम् ॥ ६ ॥)

॥ * ॥ प्रातिपदिकप्रतिषेधोऽकृत्तद्धिते ॥ * ॥

(भाष्यम्) **अकृत्तद्धितान्तस्य प्रातिपदिकस्य**

प्रतिषेधो वक्तव्यः । उदश्वित् शकृदिति ॥ अकृत्तद्धितान्तस्येति किमर्थम् ? । कुम्भकारो नगरकारः औपगवः कापटव इति ।

(प्रदीपः) प्रातिपदिकप्रतिषेध इति । यदा मञ्जकादिनिवृत्त्यर्थः प्रातिपदिकानामुपदेशः कर्तव्य इति पक्षस्तदायं प्रतिषेधः । अन्यथा उपदेशाभावात्प्राप्त्यभावादनर्थकः प्रतिषेधः स्यात् ॥ कुम्भकार इति । अपवादविषयपरिहारेणेत्संज्ञायाः प्रवर्तनात्पूर्वं प्रातिपदिकसंज्ञेति प्रतिषेधे प्राप्तेऽकृत्तद्धित इति प्रतिषेधः क्रियते ॥

(उद्द्योतः) मञ्जकादीति । मधुकादिस्थाने इत्यर्थः । अयं पक्षः परपशाह्निकान्ते भाष्ये ॥ इदं चिन्त्यम् । यद्युपदेशोऽज्ञातज्ञापकमुच्चारणं तर्हि ढकि लोप इत्यनुमितढकः उपदेशाभावादित्संज्ञानापत्तिः । मञ्जकादौ मधुकादिभ्रमनिवृत्त्यर्थं तेषामप्यनुवादस्यैव सत्त्वेनोक्तोपदेशाभावाच्च यथाकथंचिद्बोधनस्यैवोपदेशत्वे तदनुवृत्तिर्निष्फला । किं च पूर्वसूत्रे उपदेशशब्दस्य करणसाधनत्वपक्षेऽपठितानामप्येषामुपदेशत्वमस्त्येव । व्यवस्थितान्त्यं हलिति न्यासं कुर्वता वार्तिककृता तदनुवृत्तेरत्यक्तत्वाच्च ॥ ननूपदेश एव णकारलोपे पश्चात्प्रातिपदिकत्वमिति कथमत्र निषेधप्रसक्तिरत आह— अपवादेति ॥

(८३३ समाधानवार्तिकम् ॥ ७ ॥)

॥ * ॥ इदर्थाभावात्सिद्धम् ॥ * ॥

(भाष्यम्) इत्कार्याभावादत्रेत्संज्ञा न भविष्यति॥

(आक्षेपभाष्यम्)

इदमस्तीत्कार्यम्—"तित्स्वरितम्" इति स्वरितत्वं यथा स्यात् ॥

(समाधानभाष्यम्)

नैतदस्ति । प्रत्ययग्रहणं तत्र चोदयिष्यति ॥

(प्रदीपः) प्रत्ययग्रहणमिति । उदश्वित्शकृदिति चैतावव्युत्पन्नौ । शकृदिति शकेर्ऋतिन् इति यद्यपि व्युत्पाद्यते तथाप्युपदेशे तकारोन्त्यो न भवतीतीत्संज्ञा न प्रवर्तते ॥

(उद्द्योतः) ननु शकृति ऋतः प्रत्ययत्वात्तद्ग्रहणेपि दोषोऽत आह—उदश्विदिति । उदकेन श्वयत इति व्युत्पत्तावप्यस्य तकारस्य तुका निष्पन्नत्वात् प्रत्ययावयवत्वाभावात् तत्राव्युत्पन्नत्वकथनफलं चिन्त्यम् ॥ उपदेशे तकारोन्त्यो न भवतीति । इदमुक्तरीत्या चिन्त्यम् । भाष्यस्वरसस्त्वव्युत्पन्नत्व एवेति बोध्यम् ॥ किं चापदेश इत्यनुवृत्तौ प्रातिपदिकप्रतिषेध इति वार्तिकानुत्थानमेवोद्देशश्च प्रातिपदिकानां नोपदेश इत्यादेश्च इत्यादिसूत्रभाष्योक्तेः । अत एव परपशाह्निकान्ते उपदेश इत्यस्यानुवाद इत्येवार्थ एतद्भाष्यैकवाक्यत्वादिति बोध्यम् ॥

(आक्षेपभाष्यम्)

इह तर्हि राजा तक्षा ञ्नितीत्याद्युदात्तत्वं यथा स्यात् ॥

(प्रदीपः) राजा तक्षेति । नन्वव्युत्पत्तिपक्षेऽप्यनयोरवश्यमाद्युदात्तत्वमेष्टव्यम् । तत्राद्युदात्तस्याद्युदात्तत्वे किं प्रयोजनं येनेत्संज्ञा स्यात् ॥ उच्यते—आमन्त्रितनिघातप्रतिषेधार्थमाद्युदात्तत्वं स्यात् । न ङिसंबुद्ध्योरिति नलोपस्य प्रतिषेधो नेत्संज्ञाया इति तत्प्रतिबद्धः स्वरः स्यात् ॥

(उद्द्योतः) ननु संबुद्धौ न ङिसंबुद्ध्योरिति लोपनिषेधसामर्थ्यादित्त्वप्रयुक्तनलोपस्याप्यभावेन संज्ञापि नेति मन्दाशङ्कायामाह—न ङीति ॥

(समाधानभाष्यम्)

ञ्नितीत्युच्यते तत्र व्यपवर्गाभावान्न भविष्यति ॥

(प्रदीपः) व्यपवर्गाभावादिति । नित्परो नास्तीति भावः । यदा तु सौवर्यः सप्तम्यस्तदन्तसप्तम्य इति पक्षस्तदापि निदेवायं न तु निदन्त इति नास्ति स्वरः । अत्र तु पक्षे श्रोत्रियन्निति यदा वाक्यार्थे पदवचनं तदा स्वरो न सिध्यति । यदा तु छन्दसः श्रोत्रभावः घंश्च प्रत्ययस्तदा निदन्तत्वात्स्वरसिद्धिः ॥

(उद्द्योतः) नित्परो नेति । समुदायार्थत्वादुपदेशस्य स एव निद्व्यपदेशयोग्य इत्यनित्यवयवो नित्परोस्तीति न शङ्क्यम् ॥ न तु निदन्त इति । व्यपदेशिवद्भावस्त्वप्रातिपदिकेनेति निषिद्ध इत्यभिमानः ॥ अत्र त्विति । तथा चेदं भाष्यमेकदेश्युक्तिः । व्यपदेशिवद्भावोऽप्रातिपदिकेनेति निषेधस्तु प्रत्ययविधिविषय इति भावः ॥

(आक्षेपभाष्यम्)

इदं तर्हि स्वर्—"उपोत्तमं रिति" इत्येष स्वरो यथा स्यात् ॥

(समाधानभाष्यम्)

स्वरितकरणसामर्थ्यान्न भविष्यति "न्यङ्स्वरौ स्वरितौ" इति ॥

(आक्षेपभाष्यम्)

इह तर्हि अन्तर् ॥

(समाधानभाष्यम्)

उत्तमशब्दस्त्रिप्रभृतिषु वर्तते । न चात्र त्रिप्रभृतयः सन्ति ॥

(आक्षेपभाष्यम्)

इह तर्हि सनुतर्—"उपोत्तमं रिति" इत्येष स्वरो यथा स्यात् ॥

(समाधानभाष्यम्)

अन्तोदात्तनिपातनं करिष्यते । स निपातनस्वरो रित्स्वरस्य बाधको भविष्यति ॥ एतच्चात्र युक्तम्—यदित्कार्याभावादित्संज्ञा न स्यात् । यत्रेत्कार्यं भविष्यति तत्रेत्संज्ञा । तद्यथा "आगस्त्यकौण्डिन्ययोरगस्तिकुण्डिनच्" इति ॥ हलन्त्यम् ॥ ३ ॥

(प्रदीपः) तद्यथागस्त्येति । प्रत्ययस्य लुकि कृते

परिशिष्टस्य कुण्डिनजादेशः । तत्र प्रत्ययलक्षणेन तद्धितान्तत्वात्प्रातिपदिकत्वादित्संज्ञानिषेधः स्यात् । न चायं चकारस्तद्धितसंबन्धी यतोऽकृत्तद्धित इति निषेधः स्यात् ॥ ३ ॥

(उद्द्योतः) प्रत्ययस्येति । प्रतिषेधारम्भेस्य चस्येत्त्वं न स्यादिति तत्र कार्यमिति भावः । अत्र हि चित्त्वेनान्तोदात्तत्वमिष्यते प्रकृतिप्रत्ययान्यतरचित्त्वमादायैव चिदवयवकप्रकृतिप्रत्ययसमुदायस्यान्तोदात्ततायास्तेन विधानात् ॥ ३ ॥

—:o:—

(१२५ इत्संज्ञानिषेधसूत्रम् ॥१।३।१ आ. ४ सू.)

१५१ न विभक्तौ तुस्माः १।३।४ ॥

(तवर्गप्रतिषेधस्य तद्धितभिन्नपरत्वाधिकरणम्)

(८३४ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ विभक्तौ तवर्गप्रतिषेधोऽतद्धिते ॥ * ॥

(भाष्यम्) विभक्तौ तवर्गप्रतिषेधोऽतद्धित इति वक्तव्यम् । इह मा भूत् "किमोत्" 'क्व प्रेप्सन् दीव्यसे' 'क्वाद्दमासा' इति ॥

(तटस्थभाष्यम्)

स तर्हि वक्तव्यः ।

(समाधानभाष्यम्)

न वक्तव्यः । आचार्यप्रवृत्तिर्ज्ञापयति—न विभक्तौ तद्धिते प्रतिषेधो भवतीति । यदयम् "इदमस्थमुः" इति मकारस्येत्संज्ञापरित्राणार्थमुकारमनुबन्धं करोति ॥

(प्रदीपः) न विभक्तौ तुस्माः ॥ ४ ॥ इत्संज्ञापरित्राणार्थमिति । इत्संज्ञायाः परित्राणमिति साधनं कृतेति पञ्चमीतत्पुरुषः । शेषविवक्षायां वा षष्ठीसमासः । अनेनोकारेणानुमीयते येषां प्राग्दिशो विभक्तिरिति विभक्तिसंज्ञा तेषां न विभक्तावितीत्संज्ञा न निषिध्यते इति ॥

(उद्द्योतः) न विभ ॥ ४ ॥ नन्वित्संज्ञाव्यावर्तकोकारस्य कथं तत्परित्राणार्थत्वमत आह—इत्संज्ञाया इति । इटोदित्यादीनां मुखसुखार्थत्वप्रतिज्ञया श्रवणाभावस्य बोधितत्वात्तत्प्रतिज्ञयैव तेषु न विभक्तावित्यस्याप्रवृत्तिरिति नातद्धित इत्यसङ्गतम् ॥

(ज्ञापनबाधकभाष्यम्)

यद्येतज्ज्ञाप्यते इदानीमित्यत्र प्राप्नोति ॥

(उद्द्योतः) इदानीमत्र प्राप्नोतीति भाष्ये ज्ञापनकाले इत्यर्थः ॥

(ज्ञापनसाधकभाष्यम्)

इत्कार्याभावादत्रेत्संज्ञा न भविष्यति ॥

(प्रदीपः) अत्रेति । इदानीमित्यत्र ॥

(उद्द्योतः) अत्रत्यमत्रेति व्याचष्टे—इदानीमित्यत्रेति ।

(ज्ञापनबाधकभाष्यम्)

इदमस्तीत्कार्यं "मिदचोन्त्यात्परः" इत्यचामन्त्यात्परो यथा स्यात् ॥

(ज्ञापनसाधकभाष्यम्)

इशभावे कृते नास्ति विशेषः "मिदचोन्त्यात्परः' इति वा परत्वे "प्रत्ययः परः" इति वा ॥

(ज्ञापनबाधकभाष्यम्)

स एव तावदिशभावो न प्राप्नोति ॥ किं कारणम् ? । प्राग्दिशः प्रत्ययेष्वित्युच्यते ॥

(उद्द्योतः) भाष्ये—तावदिशभाव इति । प्रत्ययोत्पत्तेः पूर्वं न प्राप्नोतीत्यर्थः ।

(ज्ञापनसाधकभाष्यम्)

कः पुनरर्हतीशभावं प्राग्दिशः प्रत्ययेषु वक्तुम् । किं तर्हि ? । प्राग्दिशोर्थेष्विशभावः किंसर्वनामबहुभ्योऽद्व्यादिभ्यः प्रत्ययोत्पत्तिः ॥

(प्रदीपः) अर्थेष्विति । यथेष्टमवधिमत्कल्पनेत्यत्रार्थोऽवधिमत्त्वेनाश्रीयते । तत्रानुत्पन्न एव प्रत्यय इशभावः । ततः प्रत्ययः । यदि तु पूर्वं प्रत्ययः स्यात्तदा मित्त्वादचोन्त्यात्परे दानीमि कृते तन्मध्यपतितस्य तद्ग्रहणेन ग्रहणात्सर्वादेश इशि सति दानींविधानमनर्थकमेव स्यात् ॥

(उद्द्योतः) ननु प्राग्दिश इति शब्दस्यावधित्वेनोपादानादवधिमानपि शब्द एवेत्याशङ्क्याह—यथेष्टमिति । तस्यापि प्रकृतित्वेन सजातीयावधिमदसम्भव इति भावः ॥ अर्थ इति । तत्तत्प्रकृत्यर्थरूपोर्थः ॥ ननु प्रत्ययादेशयोर्मध्ये कदाचित्प्रथमं प्रत्ययोत्पत्तावित्कार्यं स्यादित्याशङ्क्य प्रथममादेशोत्पत्तौ विनिगमकमाह—यदि त्विति । भाष्ये किं तर्हि ? प्राग्दिशोर्थेष्विशभाव इत्युक्ते एवमपि परत्वात्प्रत्यय एव पूर्वमुचित इत्याशङ्क्योक्तम्—किंसर्वनामबहुभ्योऽद्व्यादिभ्यः प्रत्ययोत्पत्तिरिति । एवं च द्व्यादिभेदज्ञानसापेक्षत्वेन बहिरङ्गप्रत्ययात्पूर्वमन्तरङ्गत्वादादेश एव । अत्रैवार्थे दानींग्रहणमपि ज्ञापकमिति तद्भावं केचित् ॥ वस्तुतोऽयमपाठः । इदमो र्हिलित इदम इत्यनुवर्तमाने दानीमो विधानात् । कैयटस्वरसोप्येवमेव ॥

(ज्ञापनबाधकभाष्यम्)

एवं तर्हि तदोप्ययं वक्तव्यः । तदश्च मिदचोन्त्यात्परत्वेन न सिध्यति ॥

(प्रदीपः) तदोप्ययमिति । तदो दा चेति चकारेणानुकर्षणात् ॥

(ज्ञापनसाधकभाष्यम्)

ननु चात्राप्यत्वे कृते नास्ति विशेषः "मिदचोन्त्यात्परः" इति वा परत्वे 'प्रत्ययः पर' इति वा ॥

(प्रदीपः) ननु चेति । सप्तम्यां विभक्तावुत्पन्नायामत्वे कृते दानीमिति भावः ॥

(उद्द्योतः) अत्वप्रवृत्तिप्राथम्ये विनिगमकमाह—सप्तम्यामिति । अन्तरङ्गानपीतिन्यायमसौ न जानीते इति बोध्यम् ॥

(ज्ञापनबाधकभाष्यम्)

तद्धि अत्वं न प्राप्नोति ॥ किं कारणम्? । विभक्तावित्युच्यते ॥

(प्रदीपः) तद्धीति । प्राग्दिशोर्थेष्विति पूर्वमभिधानात्सप्तम्यर्थवृत्तेः कालवाचिनो मित्वान्मध्ये दानीमा भाव्यमिति तदानीमित्यस्यासिद्धिरेवेत्यर्थः ॥

(उद्द्योतः) सप्तम्यर्थेति । प्राग्दिश इतिवत् सप्तम्या इत्यप्यर्थपरमेव । प्रातिपदिकाच्च तद्धितोत्पत्तिरिति भावः । अन्तरङ्गानपीतिन्यायाच्च ॥

(समाधानभाष्यम्)

एवं तर्हि यकारान्तो दानीं करिष्यते ॥ किं यकारो न श्रूयते? ॥ लुप्तनिर्दिष्टो यकारः ॥ न विभक्तौ ॥ ४ ॥

(प्रदीपः) यकारान्त इति । यकारोन्त्यत्वमनुभवन्मकारस्यान्त्यत्वं प्रतिबध्नाति । यकारस्य च संयोगान्तस्य लोप इति लोपः क्रियते ॥ यद्येवं मकार एवोपदेशेऽन्त्यः श्रूयते इति प्राप्नोत्येव मकारस्येत्संज्ञा । नैतदस्ति । पूर्वत्रासिद्धमिति मकारस्येत्संज्ञायां यलोपस्यासिद्धत्वादन्त्यत्वाभावात् ॥ ४ ॥

(उद्द्योतः) ननु यकारसत्त्वेपि दानीमित्यस्य मोन्त्य एवेत्यत आह—यकार इति ॥ संयोगान्तस्य लोप इति । चिन्त्यमिदम् । यणः प्रतिषेधात् । तस्माद्यशब्दनिमित्तको लोपो व्योरिति लोप इति वक्तुमुचितम् ॥ उपदेशोन्त्य इति । व्यवसितस्यान्त्यः श्रूयत इति वक्तुमुचितम् ॥ पूर्वत्रेति । वस्तुतस्तु लोपो व्योरित्यस्य बहिरङ्गतयाऽसिद्धत्वमित्संज्ञां प्रतीति बोध्यम् । न च यकारे कृतेपि मान्तस्य प्रत्ययतया व्यवसितान्त्यत्वेन दुर्वारैवेत्संज्ञेति वाच्यम् । व्यवसितान्त्यशब्देन प्रत्यासत्त्या शास्त्रकृद्व्यवसितान्त्यस्यैव ग्रहणेनादोषात् तद्व्यवसितश्च यान्त इति बोध्यम् । उत्तरसूत्रस्थस्य यकारादी चुञ्चुपूचणपाविति भाष्यस्य योजनार्थं मदुक्तप्रकार आवश्यक इति बोध्यम् ॥ ४ ॥

(इत्संज्ञासूत्रम् ॥ १ । ३ । १ आ. ५ सू०)

१५४ चुटू १।३।७ ॥

(अनिष्टनिराकरणाधिकरणम्)

(८३५ आक्षेपवार्तिकम् ॥ २ ॥)

॥ * ॥ चुञ्चुपूचणपोश्चकारप्रतिषेधः ॥ * ॥

(व्याख्याभाष्यम्)

चुञ्चुपूचणपोश्चकारस्य प्रतिषेधो वक्तव्यः । केशचुञ्चुः । केशचणः ॥

(८३६ समाधानवार्तिकम् ॥ २ ॥)

॥ * ॥ इदर्थाभावात्सिद्धम् ॥ * ॥

(व्याख्याभाष्यम्)

इत्कार्याभावादत्रेत्संज्ञा न भविष्यति ॥

(समाधाननिराकरणभाष्यम्)

इदमस्तीत्कार्यम् । "चितः" अन्त उदात्तो भवतीति अन्तोदात्तत्वं यथा स्यात् ॥

(समाधानसाधकभाष्यम्)

पित्करणमिदानीं किमर्थं स्यात्? ॥

(८३७ समाधानबाधकवार्तिकम् ॥ ३ ॥)

॥ * ॥ पित्करणं किमर्थमिति चेत्पर्यायार्थम् ॥ * ॥

(व्याख्याभाष्यम्)

पित्करणं किमर्थमिति चेत्पर्यायार्थमेतत्स्यात् ॥

(सिद्धान्तिसमाधानभाष्यम्)

एवं तर्हि यकारादी चुञ्चुपूचणपौ ॥ किं यकारो न श्रूयते? । लुप्तनिर्दिष्टो यकारः ॥

(प्रदीपः) चुटू ॥७॥ लुप्तनिर्दिष्ट इति । पूर्वं निर्दिष्टः पश्चाल्लुप्त इत्यर्थः । राजदन्तादेराकृतिगणत्वाद्भाष्यकारवचनाद्वा पूर्वकालस्य परनिपातः ॥ अथ वा लुप्तोयमिति प्रतिज्ञातो लुप्तनिर्दिष्टः ॥

(उद्द्योतः) चुटू ॥ ७ ॥ क्रमस्य निर्देशायोगादाह—पूर्वमिति । इति प्रतिज्ञात इति । निर्दिष्टशब्दः प्रतिज्ञातार्थको मध्यमपदलोपी च समास इति भावः ॥

(८३८ आक्षेपवार्तिकम् ॥ ४ ॥)

॥ * ॥ इर उपसंख्यानम् ॥ * ॥

(व्याख्यानभाष्यम्)

इर उपसंख्यानं कर्तव्यम् । रुधिर् । अरुधत् । अरौत्सीत् ॥

(प्रदीपः) इर उपसंख्यानमिति ॥ इरितो वेत्यत्रेरिति समुदायानुकरणम् इर इत् यस्य सोयमिरित् । समुदायस्य चाज्झलात्मकत्वादप्राप्ता इत्संज्ञोपसंख्यायते । समुदायस्यैवेत्संज्ञासंबन्धेऽवयवाः पारतन्त्र्यादित्संज्ञां न लभन्त इतीदित्त्वाभावान्नुमभावः ॥ नन्वेवं सति स्वरितेत इत्यात्मनेपदं न प्राप्नोति । नैष दोषः । स्वरितत्वप्रतिज्ञानसामर्थ्यादवयवगतं स्वरितत्वं समुदाय आरोपयिष्यते ॥

(उद्द्योतः) नन्विरित इत्यादाविराविती यस्येति विग्रहाद् हलन्त्यमुपदेशेजित्येव सिद्धे इदं व्यर्थमत आह—इरित इति ॥

(८३९ समाधानवार्तिकम् ॥ ५ ॥)

॥ * ॥ अवयवग्रहणात्सिद्धम् ॥ * ॥

(व्याख्याभाष्यम्)

रेफस्यात्र "हलन्त्यम्" इति भविष्यति, इकारस्य "उपदेशेऽजनुनासिक इत्" इति ॥

(प्रदीपः) अवयवग्रहणादिति । इराविती यस्य स इरिदित्येवमित्संज्ञकत्वेनावयवावेवाश्रीयेते न तु समुदाय इत्यर्थः ॥

(उद्द्योतः) इराविताविति । लक्ष्यानुरोधाद् द्विवचनान्तेनापि विग्रह इति भावः । एवं चात्मनेपदार्थं सामर्थ्यं नाश्रयणीयमिति बोध्यम् ॥

(८४० समाधानबाधकवार्तिकम् ॥ ६ ॥)

॥ * ॥ अवयवग्रहणादिति चेदिदिद्विधिप्रसङ्गः ॥ * ॥

(व्याख्याभाष्यम्)

अवयवग्रहणादिति चेदिदिद्विधिरपि प्राप्नोति । भेत्ता छेत्ता "इदितो नुम् धातोः" इति नुम् प्राप्नोति ॥

(समाधानसाधकभाष्यम्)

यदि पुनरयमिदिद्विधिः कुम्भीधान्यन्यायेन विज्ञायेत । तद्यथा—कुम्भीधान्यः श्रोत्रिय इत्युच्यते । यस्य कुम्भ्यामेव धान्यं स कुम्भीधान्यः । यस्य पुनः कुम्भ्यां चान्यत्र च धान्यं नासौ कुम्भीधान्यः ॥

(प्रदीपः) यदि पुनरिति । यस्य च कुम्भीस्थादन्यन्निहितं धान्यं नास्ति स कुम्भीधान्यः ॥

(समाधानबाधकभाष्यम्)

नायमिदिद्विधिः कुम्भीधान्यन्यायेन शक्यो विज्ञातुम् । इह हि दोषः स्यात्—टुनदि नन्दथुरिति ।

(प्रदीपः) यद्यपि नुम्विधावस्य न्यायस्य निमित्तं नास्ति तथापि दोषेणैव तन्न्यायानाश्रयणमाह—नायमिति ।

(उद्द्योतः) यद्यपीति । दानपात्रतासिद्धये विशेषणकुम्भ्यामन्वितैवकारगर्भसमासेनान्ययोगव्यवच्छेदलाभेपि प्रकृते तदाश्रयणे प्रमाणाभावादिति भावः ।

(समाधानसाधकभाष्यम्)

एवं तर्हि नैवं विज्ञायते—इकार इदस्य सोयमिदित् तस्येदित इति ॥ कथं तर्हि ? ॥ इकार एवेत् इदित् इदिदन्तस्येति ॥

(प्रदीपः) इकार एवेदिति । इदिता धातुर्विशेष्यत इति तदन्तविधिः ॥

(उद्द्योतः) भाष्ये इकार एवेदिति । तत्पुरुषत्वमेवास्य न बहुव्रीहित्वमित्येतत्सूचनायैवकारः ॥

(समाधानान्तरभाष्यम्)

[अथ वा ऋकारस्यैवेदमित्त्वभूतस्य ग्रहणम् । तस्य च "उपदेशेऽजनुनासिक" इतीत्संज्ञा भविष्यति ॥

(प्रदीपः) ऋकारस्येति । ऋत इद्धातोरितीत्त्वे रपरत्वे च भिदिरित्यादिनिर्देशः । अनङ्गस्यापि निपातनादित्त्वम् । तत्र च भिदृशब्दे पूर्वमृकारस्येत्संज्ञा । तत इत्त्वरपरत्वे । इरितो वेत्यत्रापि ऋ इदस्येति समासे कृते निपातनादित्त्वरपरत्वयोः कृतयोरिरित इति निर्देशः ॥

(उद्द्योतः) अङ्गाधिकारस्थत्वेन प्रत्ययनिमित्तत्वात्तदप्राप्तेराह—अनङ्गस्यापीति । अधातोरित्यपि बोध्यम् । न धात्विति-सूत्रस्थभाष्यकैयटरीत्याऽनुबन्धविनिर्मुक्तस्यैव धातुत्वात् । अत एव भाष्ये सूत्रे नोपन्यस्तम् ॥ इत्संज्ञायाः परत्वादित्त्वे इष्टसिद्धिर्न स्यादत आह—तत्रेति । निर्देशानुपपत्तिकल्पितमित्त्वं बहिरङ्गमिति भावः । निपातनादेवेत्त्वरपरत्वाभ्यां पूर्वं तस्य लोप इत्यपि नेति बोध्यम् ॥]

(समाधानान्तरभाष्यम्)

अथ वा आचार्यप्रवृत्तिर्ज्ञापयति—'नैवंजातीयकानामिदिद्विधिर्भवति' इति ॥ यदयमिरितः कांश्चिन्नुमनुषक्तान्पठति—उबुन्दिर् निशामने । स्कन्दिर् गतिशोषणयोः ॥

(प्रदीपः) नुमनुषक्तानिति । नुमा नकारो लक्ष्यते नकारयुक्तानित्यर्थः । न च लोपाभावार्थो नकारोपदेश इति वक्तुं शक्यम् । अनकारोपदेशेपीदित्त्वान्नलोपस्याप्रसङ्गः । तस्मान्नकारोपदेशेनेरितामिदित्कार्याभावो ज्ञाप्यते ॥ न दृश इति क्सादेशनिषेधेनापीरितामिदित्कार्याभावो ज्ञायते । अन्यथा दृशेरिदित्त्वान्नुमि सति इगुपधत्वाभावात्प्राप्तिरेव क्सस्य नास्तीति किं तन्निषेधेन ॥

(उद्द्योतः) नुमोभावादाह—नुमेति । एतज्ज्ञाप्यात्केषांचिद्यातनामर्थनिर्देशसहितोपि पाठ इति ज्ञायते ॥ किं तन्निषे-

धेनेति । यद्यपि तेनोपदेश इगुपधत्वं विवक्ष्यते इत्यपि ज्ञापनं संभवति, तथापि लक्ष्यानुरोधादिदमेव ज्ञाप्यत इत्यभिमानः ॥

(समाधानान्तरभाष्यम्)

[अथवा आचार्यप्रवृत्तिर्ज्ञापयति—'इर्शब्दस्येत्संज्ञा भवति' इति। यदयम् 'इरितो वा' इत्याह॥]

(समाधानान्तरभाष्यम्)

अथ वान्त इति वर्तते ॥

(प्रदीपः) अन्त इति । गोः पादान्त इत्यतः । तेनान्तेदितां धातूनां नुमागमो न तु मध्येदिताम् ॥

(उद्द्योतः) गोः पादान्त इति समानयोगनिर्दिष्टानामेकदेशोपि स्वरितत्वप्रतिज्ञासामर्थ्यादनुवर्तेत इति भावः । अन्तपदार्थस्येकारविशेषणत्वेपि सौत्रत्वात्समास इति बोध्यम् ॥ अत्र पृथगित्संज्ञा, इदित इति कर्मधारयात् षष्ठीति युक्तः पक्षः ॥ ७ ॥

(१२७ लोपविधिसूत्रम् ॥ १ । ३ । १ आ. ६ सू.)

१५६ तस्य लोपः ॥ १ । ३ । ९ ॥

(तस्यपदोपादानप्रयोजनाधिकरणम्)

(आक्षेपभाष्यम्)

तस्यग्रहणं किमर्थम् ? ॥

(प्रदीपः) तस्य लोपः ॥ ९ ॥ तस्यग्रहणमिति । अभावो लोपः स च भावोपाधिरेव प्रतीयते नान्यथेति प्रकरणादित्संज्ञस्यैव लोपो भविष्यतीति प्रश्नः ॥

(उद्द्योतः) तस्य लोपः ॥ ९ ॥ अभावो लोप इति । दर्शनाभावो लोप इत्यर्थः ॥ भावोपाधिरिति । दर्शनस्य सविषयत्वाच्छब्दशास्त्रत्वाच्छब्दरूप एव स विषयः । किं च भावविरोध्यभावपदस्यार्थः । एवं च भावोपाधिरेव स भावप्रतियोगिक एव स इति भावः ॥

(आक्षेपबाधकभाष्यम्)

इत्संज्ञकः प्रतिनिर्दिश्यते ॥

(आक्षेपसाधकभाष्यम्)

नैतदस्ति प्रयोजनम् । प्रकृतमिदिति वर्तते ॥ क्व प्रकृतम् ? । "उपदेशेऽजनुनासिक इत्" इति ॥

(आक्षेपबाधकभाष्यम्)

तद्वै प्रथमानिर्दिष्टं षष्ठीनिर्दिष्टेन चेहार्थः ॥

(आक्षेपसाधकभाष्यम्)

अर्थाद्विभक्तिविपरिणामो भविष्यति । तद्यथा—'उच्चानि देवदत्तस्य गृहाणि, आमन्त्रयस्व' [एनम्] देवदत्तमिति गम्यते ॥ 'देवदत्तस्य गावोऽश्वा हिरण्यं च, आढ्यो वैधेयः' देवदत्त इति गम्यते । पुरस्तात्षष्ठीनिर्दिष्टं सदर्थात् द्वितीयानिर्दिष्टं प्रथमानिर्दिष्टं च भवति । एवमिहापि पुरस्तात्प्रथमानिर्दिष्टं सदर्थात्षष्ठीनिर्दिष्टं भविष्यति ॥

(प्रदीपः) विभक्तिविपरिणाम इति । सादृश्यात्तत्त्वाध्यवसायाद्विपरिणामव्यवहारः । वाक्यान्तरे तु योग्यविभक्त्यन्तं परमार्थतः शब्दान्तरमेव संनिधीयते ॥

(उद्द्योतः) ननु प्रकृतस्यान्वययोग्यत्वेऽनुपपत्तिः, अयोग्यत्वेऽध्याहार एवेति विपरिणामो ऽसंगतो ऽत आह—सादृश्यादिति । एवं चैकदेशसारूप्येण विपरिणामव्यवहार इति भावः ॥ भाष्ये आमन्त्रयस्वेत्येतदन्तमेव लौकिकं वाक्यम् । तत्र प्रकृतत्वादेनमिति गम्यत इत्यर्थः । तद्व्याचष्टे—देवदत्तमिति गम्यत इति । एनमित्यस्य सामान्यशब्दत्वाद्विशेषलाभायेदमुक्तम् ॥ वैधेयो मूर्खः ॥

(समाधानभाष्यम्)

इदं तर्हि प्रयोजनम्—ये अनेकाल इत्संज्ञास्तेषां लोपः सर्वादेशो यथा स्यात् ॥

(आक्षेपभाष्यम्)

अथ क्रियमाणेपि वै तस्यग्रहणे कथमिव लोपः सर्वादेशो लभ्यः ॥

(समाधानभाष्यम्)

लभ्य इत्याह ॥ कुतः ? । वचनप्रामाण्यात् । तस्यग्रहणसामर्थ्यात् ॥

(प्रदीपः) तस्यग्रहणसामर्थ्यादिति। अलोन्त्यस्येत्यन्त्यस्य लोपे प्रसक्ते तस्यग्रहणेन समुदायस्य लोपः प्रतिपाद्यते ॥

(उद्द्योतः) अलोन्त्यस्येति । नानर्थक इति परिभाषा त्वलोन्त्यात्पूर्वे प्रत्याख्यास्येवेति भावः ॥

(णलादीनां लोपसाधनाधिकरणम्)

(८४१ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ इतो लोपे णलुक्त्वानिष्ठासूपसंख्यानमित्प्रतिषेधात् ॥ * ॥

(भाष्यम्) इतो लोपे णलुक्त्वानिष्ठासूपसंख्यानं कर्तव्यम् ॥ णल्—अहं पपच । क्त्वा—देवित्वा सेवित्वा ॥ निष्ठा—शयितः शयितवान् ॥ किं पुनः कारणं न सिध्यति ? ॥ इत्प्रतिषेधात् ॥ प्रतिषिध्यते तत्रेत्संज्ञा । णलुत्तमो णिद्वा भवति । क्त्वा सेण् न किद्भवति । निष्ठा सेण् न किद्भवतीति ॥

(८४२ समाधानवार्तिकम् ॥ २ ॥)

॥ * ॥ सिद्धं तु णलादीनां ग्रहणप्रतिषेधात् ॥ * ॥

(भाष्यम्) सिद्धमेतत् ॥ कथम् ?। णलादीनां ग्रहणानि प्रतिषिध्यन्ते । णलुत्तमो वा णिद्ग्रहणेन गृह्यते । क्त्वा सेण्न किद्ग्रहणेन गृह्यते । निष्ठा सेण्ण किद्ग्रहणेन गृह्यत इति ॥

(प्रदीपः) ग्रहणप्रतिषेधादिति । नैषामित्संज्ञा प्रतिषिध्यतेऽपि तु तत्प्रतिबद्धं कार्यमित्यर्थः ॥

(उद्योतः) तस्यग्रहणेनेत्संज्ञकपरामर्शिनाऽश्रुतत्वाद् ग्रहणं कथं प्रतिषिध्यतेऽत आह—नैषामिति । णिदादिपदलक्षिततत्कार्याणां प्रतिषेध इति भावः ॥ भाष्ये ग्रहणानीत्यस्य णिदादिपदैर्ग्रहणप्रयुक्तानि कार्याणीत्यर्थः । अग्रेपि णिद्ग्रहणेन गृह्यते यत्कार्यं तत्कार्यं लभत इत्यादिक्रमेणार्थः । विकल्पेपि प्रतिषेधोस्तीति प्रतिषिध्यन्त इत्युक्तम् ॥

(८४३ समाधानान्तरवार्तिकम् ॥ ३ ॥)

॥ * ॥ निर्दिष्टलोपाद्वा ॥ * ॥

(भाष्यम्) निर्दिष्टलोपाद्वा सिद्धमेतत् । अथ वा निर्दिष्टस्यायं लोपः क्रियते तस्मात्सिद्धमेतत् ॥

(प्रदीपः) निर्दिष्टलोपाद्वेति । तस्येत्यनेनेत्संज्ञाप्रकरणे निर्दिष्टस्य परामर्शादसत्यामपीत्संज्ञायां लोपो भवतीत्यर्थः ॥

(उद्योतः) निर्दिष्टेति । उच्चारितशब्दप्रतिपादितत्वमेवात्र निर्दिष्टत्वं विवक्षितम् । अत एव णादीनां निर्दिष्टत्वमिति भावः । अयं पक्ष एकदेशिनः सर्वलोपासिद्धेः ॥

(८४४ आक्षेपवार्तिकम् ॥ ४ ॥)

॥ * ॥ तत्र तुस्मानां प्रतिषेधः ॥ * ॥

(भाष्यम्) तत्र तुस्मानां प्रतिषेधो वक्तव्यः । तस्मात् । तस्मिन् । यस्मात् । यस्मिन् । वृक्षाः । प्लक्षाः । अचिनवम् । असुनवम् । अकरवम् ॥

(प्रदीपः) तुस्मानामिति । यद्यसत्यामपीत्संज्ञायां लोपो भवति तदा तुस्मानामपि प्राप्नोति । ते हि हलन्त्यमित्यत्र निर्दिष्टाः ॥

(८४५ समाधानवार्तिकम् ॥ ५ ॥)

॥ * ॥ न वोच्चारणसामर्थ्यात् ॥ * ॥

(भाष्यम्) न वा वक्तव्यः । किं कारणम् । उच्चारणसामर्थ्यादत्र लोपो न भविष्यति ॥

(प्रदीपः) नवेति । इत्संज्ञाया: प्रतिषेधादेषामित्कार्यं नास्ति । यदि चानेन लोपः स्यादुपदेशस्तेषामनर्थकः स्यात् ॥

(उद्योतः) इत्संज्ञाद्वारा तत्कार्यार्थमुच्चारणमस्त्वित्यत आह—इत्संज्ञाया इति ॥

(विप्रतिषेधनिराकरणाधिकरणम्)

(८४६ आक्षेपवार्तिकम् ॥ ६ ॥)

॥ * ॥ अनुबन्धलोपे भावाभावयोर्विप्रतिषेधादप्रसिद्धिः ॥ * ॥

(भाष्यम्) अनुबन्धलोपे भावाभावयोर्विरोधादप्रसिद्धिः । न ज्ञायते केनाभिप्रायेण प्रसजति केन निवृत्तिं करोतीति ॥

(प्रदीपः) अनुबन्धलोप इति । यथा कश्चिद्वक्ति घटोस्तीति पुनश्च वक्ति नास्तीति तथानुबन्धानामुच्चारणाद् भावानुज्ञानं लोपविधानाच्चाभावानुज्ञेति विरोधादप्रामाण्यप्रसङ्गः॥

(उद्योतः) नन्वनुबन्धाः श्रूयन्त इति वचनाभावात् कथं विरोधोऽत आह—यथेति । अनुमितेन विरोध इति भावः ॥

(८४७ समाधानवार्तिकम् ॥ ७ ॥)

॥ * ॥ सिद्धं त्वपवादन्यायेन ॥ * ॥

(भाष्यम्) सिद्धमेतत् । कथम् ? ॥ अपवादन्यायेन ॥ किं पुनरिह तथा यथोत्सर्गापवादौ ? ॥

(८४८ समाधानसाधकवार्तिकम् ॥ ८ ॥)

॥ * ॥ भावो हि कार्यार्थोऽनन्यार्थो लोपः ॥ * ॥

(भाष्यम्) कार्यं करिष्यामीत्यनुबन्ध आसज्यते कार्यादन्यन्मा भूदिति लोपः ॥

(प्रदीपः) सिद्धमिति । यथाऽणं को बाधते तथा कार्ये चरितार्थमुच्चारणात्प्राप्तं भावं लोपोऽनन्यार्थो बाधते ॥

(उद्योतः) सामान्यविशेषभावाभावात्कथमपवादन्यायोऽत आह—यथाऽणमिति । विषयान्तरे चरितार्थमित्यर्थः ॥ कार्ये इत्त्वप्रयुक्ते ॥ भाष्ये कार्यादन्यच्छ्रवणम् ॥

(अनुबन्धानामेकान्तत्वाधिकरणम्)

(आक्षेपभाष्यम्)

अथ यस्यानुबन्ध आसज्यते किं स तस्यैकान्तो भवत्याहोस्विदनेकान्तः ? ॥

(प्रदीपः) एकान्त इति । एकदेशः । अवयव इत्यर्थः । अनेकान्तस्तूपलक्षणमेव केवलम् । यथा गृहस्य काकः । तत्रोपलभ्यमानस्य रूपद्वयदर्शनाद्वृक्षे शाखाबलाकयोरिवेति प्रश्नः ॥

(उद्योतः) सन्देहबीजं दर्शयति—तत्रोपलभ्यमानस्येति ॥

(८४९ एकान्तपक्षाभ्युपगमवार्तिकम् ॥ ८ ॥)

॥ * ॥ एकान्तस्तत्रोपलब्धेः ॥ * ॥

(भाष्यम्) एकान्त इत्याह । कुतः ?। तत्रोपलब्धेः । तत्रस्थो ह्यसावुपलभ्यते । तद्यथा—वृक्षस्था शाखा वृक्षैकान्तोपलभ्यते ॥

(प्रदीपः) एकान्तस्तत्रोपलब्धेरिति। ननु यदेव संशयनिमित्तं स [एव] कथं निश्चयहेतुः। उच्यते—सामर्थ्यादवधारणमाश्रीयते॥ तत्रैवोपलब्धेरिति। अवयवस्तत्रैवोपलभ्यते। अनवयवस्तु तत्र चान्यत्र च॥ ननु वकारस्य वनव्रणवृक्षादिषु बहुषूपलब्धिः, न चासावनवयवः। नैष दोषः। भिन्नसमुदायविषयं वर्णान्तरमेव तदिति शकुनिभाष्ये प्रतिपादितम्॥

(उद्द्योतः) शकुनिभाष्ये इति। यदि पुनरिमे वर्णाः शकुनिवत्स्युरान्यभाव्यं तु कालशब्दव्यवायादित्यत्रेत्यर्थः। एक एव ककार इति पक्षेपि न दोषः। लोपशास्त्रज्ञानात्पूर्वं यस्तत्रोपलभ्यते एव सोवयव इत्यर्थात्। अन्यथा शाखाया अपि छेदनोत्तरमन्यत्रोपलम्भात्तत्रैवोपालम्भाभावेनानवयवत्वं स्यात्। एवं चानुपलम्भकपक्षं विनापि तत्रान्यत्र चोपलभ्यमानोऽनवयवः तं विना तत्रोपलभ्यमान एव यः सोऽवयव इति भाष्याशय इत्यन्ये॥

(८५० एकान्तपक्षदूषणवार्तिकम्॥ ९॥)

॥ * ॥ तत्रासरूपसर्वादेशदाप्प्रतिषेधे पृथक्त्वनिर्देशोनाकारान्तत्वात्॥ * ॥

(भाष्यम्) तत्रासरूपविधौ दोषो भवति—"कर्मण्यण्" "आतोऽनुपसर्गे कः" इति कविषयेऽणपि प्राप्नोति॥

सर्वादेशे च दोषो भवति। "दिव औत्" औत्सर्वादेशः प्राप्नोति॥

दाप्प्रतिषेधे पृथक्त्वनिर्देशः कर्तव्यः—'अदाप्दैपौ' इति वक्तव्यम्। किं पुनः कारणं न सिध्यति?। अनाकारान्तत्वात्॥ ननु चात्त्वे कृते भविष्यति॥ तद्ध्यात्त्वं न प्राप्नोति॥ किं कारणम्?। अनेजन्तत्वात्॥

(प्रदीपः) तत्रासरूपेति। अनाकारान्तत्वादित्येतद्दाप्प्रतिषेध इत्यनेनैव सामर्थ्यात्सम्बध्यते॥ कविषय इति। एकान्तत्वे वैरूप्यात्समावेशप्रसङ्गः। अनेकान्तत्वे तूभावप्यकाराविति सारूप्यादसमावेशः॥ अनेजन्तत्वादिति। यथा ढौकतेः ककारस्यैकान्तत्वादात्त्वं न भवत्येवं दैपोपि न प्राप्नोति। उपदेशग्रहणाच्च लुप्तेपि पकारे न प्राप्नोति॥

(उद्द्योतः) भाष्ये—तत्रेत्यस्यैकान्तपक्षे इत्यर्थः॥ अनाकारान्तत्वादित्येतदिति। असरूपसर्वादेशेतिपदे लुप्तसप्तमीके दोषपदाध्याहारेण योज्ये इति भावः॥ एतेन द्वन्द्वे एकदेशान्वयः कथमित्यपास्तम्। अत एव दाप्प्रतिषेध इति वार्तिके एकवचनम्॥ भाष्ये दिव औदिति। यद्यप्ययमुच्चारणार्थस्तथापि समभिव्याहृतवर्णोच्चारणे सहायसंपादकतया तस्य चारितार्थ्येन विधेयविषये विशिष्टस्यापि विधेयत्वसम्भावनासत्त्वादित्संज्ञालोपयोः प्रवृत्तयोर्बाधे मानाभावादुच्चारणार्थानामपीत्त्वमस्त्येव। किं च तदभावे उच्चारितस्य निवृत्तिः कथं स्यादिति भावः॥ एतेनोच्चारणार्थानामित्संज्ञा नेति नव्योक्तिः परास्ता॥ स्तीर्णे बर्हिषि समिधानेग्नावित्यादौ छेरौति स्वरितत्वाभावस्तु छान्दसत्वादिति बोध्यम्॥ न चोच्चारणार्थानामपीत्त्वे णौ गमिरित्याद्यादेशानां नुमापत्तिः। भाविधातुत्वमादाय तत्रैका निर्देशेनादोषात्। अत एव मुमुत्पत्तिः। अन्यथा इनो वध लिङीतिवत्सा न स्यात्। उच्चारणार्थानामपीत्त्वं च स्लेः सिच्' 'वेरपृक्तस्ये'त्यादौ भाष्ये स्पष्टमुक्तम्। अनुवादविषये तूच्चारणार्थवर्णविशिष्टस्य तद्रहिते लक्षणा बोध्या। न विधौ परः शब्दार्थ इति विधेयबोधके लक्षणानौचित्यमिति दिक्॥ उपदेशग्रहणाच्चेति। यस्यादेच इति सूत्रे भाष्ये मीनातिमिनोतिदीङामिति सूत्रे एज्ग्रहणानुवृत्तिसामर्थ्यात्परनिमित्तकस्यैच आत्वं नेत्यर्थमाश्रित्योपदेशग्रहणं प्रत्याख्यातम्, तत्तु मीनातिमिनोतीतिसूत्रस्थभाष्यविरोधादेकदेश्युक्तिः। तत्र अवदानसिद्धये एज्विषये आत्वमिति सिद्धान्तितं नहि तदोकार्थज्ञापकत्वं तस्येति भावः॥

(अनेकान्तपक्षाभ्युपगमभाष्यम्)

अस्तु तर्ह्यनेकान्तः॥

(प्रदीपः) अस्तु तर्हीति। कार्यलक्षणाय केवलमनुबन्ध उपात्तो न तु तस्यावयवः॥

(उद्द्योतः) अनेकान्तत्वे उपदेशानर्थक्यमत आह—कार्यलक्षणायेति। कार्यप्रवृत्तये इत्यर्थः॥

(८५१ अनेकान्तपक्षदूषणवार्तिकम्॥ १०॥)

॥ * ॥ अनेकान्ते वृत्तिविशेषः॥ * ॥

(भाष्यम्) यदि अनेकान्तो, वृत्तिविशेषो न सिध्यति। किति णितीति कार्याणि न सिध्यन्ति। किं हि स तस्य भवति, येनेत्कृतं स्यात्?।

(प्रदीपः) वृत्तिविशेष इति। बहुव्रीहिर्न सिद्ध्यति। अनेकान्तत्वे क इद्यस्येति संबन्धाभावात्॥

(अनन्तरपक्षाभ्युपगमभाष्यम्)

एवं तर्ह्यनन्तरः॥

(प्रदीपः) अनन्तर इति। यद्यप्यनन्तरादिषु बहुव्रीहिर्न भवति तथापीह वचनसामर्थ्याद्भवति॥

(उद्द्योतः) सामर्थ्यादिति। सौत्रत्वादिति भावः। अनन्तरेप्यवयवत्वारोपेणेति भाव इत्यन्ये॥

(८५२ अनन्तरपक्षदूषणवार्तिकम्॥ ११॥)

॥ * ॥ अनन्तर इति चेत्पूर्वोत्तरयोरित्कृतप्रसङ्गः॥ * ॥

(भाष्यम्) अनन्तर इति चेत्पूर्वोत्तरयोरित्कृतं प्राप्नोति। कुञ्छण्॥

(८५३ समाधानवार्तिकम्॥ १२॥)

॥ * ॥ सिद्धं तु व्यवसितपाठात्॥ * ॥

(भाष्यम्) सिद्धमेतत्। कथम्?। व्यवसितपाठः

कर्तव्यः। वुञ् छण्। स चावश्यं पाठः कर्तव्यः।

(प्रदीपः) व्यवसितपाठादिति। व्यवसितानां विच्छिन्नानां पाठः कर्तव्यः। ततः पूर्वस्यैवासावनन्तरः न तु परस्य। कालव्यवधानात्॥

(उद्द्योतः) हलन्त्यसूत्रनिर्णीतधातुत्वादिना परिच्छिन्नत्वरूपव्यवसितत्वस्यात्रासंभवादाह—विच्छिन्नानामिति॥

(८५४ समाधानसाधकवार्तिकखण्डम्॥ १२॥)

॥ * ॥ इतरथा ह्येकान्तेपि संदेहः॥ * ॥

(भाष्यम्) अक्रियमाणे व्यवसितपाठे एकान्तेपि संदेहः स्यात्। तत्र न ज्ञायते किमयं पूर्वस्य भवत्याहोस्वित्परस्येति॥

(संदेहापाकरणभाष्यम्)

संदेहमात्रमेतद्भवति। सर्वसंदेहेषु चेदमुपतिष्ठते 'व्याख्यानतो विशेषप्रतिपत्तिर्न हि संदेहादलक्षणम्' इति। पूर्वस्येति व्याख्यास्यामः॥

(प्रदीपः) व्याख्यानत इति। एकान्तपक्षे एकोवयवो द्वयोर्न भवतीति सन्देहे व्याख्यानान्निश्चयः। अनेकान्तत्वे त्वानन्तर्यस्योभयापेक्षस्य विरोधाभावाद्व्यवसितपाठ एव कर्तव्यः॥

(उद्द्योतः) नन्वनेकान्तत्वेपि व्याख्यानान्निर्णयोऽत आह—अनेकान्तत्वे त्विति। विरोधाभावादिति। एवं च सन्देहाभावान्न व्याख्यानप्रवृत्तिरिति भावः। विरुद्धानेककोटिविषयज्ञानस्यैव सन्देहत्वादिति तात्पर्यम्।

(८५५ समाधानान्तरवार्तिकम्॥ १३॥)

॥ * ॥ वृत्ताद्वा॥ * ॥

(भाष्यम्) वृत्ताद्वा सिद्धमेतत्। वृद्धिमन्तमाद्युदात्तं दृष्ट्वा ञिदिति व्यवसेयम्। अन्तोदात्तं दृष्ट्वा किदिति॥

(प्रदीपः) वृत्ताद्वेति। वृत्तं प्रयोगः॥ नन्वाचार्यो भवतु वृत्तज्ञः शिष्यास्तु कथं प्रतिपद्यन्ते॥ व्याख्यानाच्चेत्। पूर्वमेवैतदुक्तम्। वृत्ताद्वेत्यनेन किं तदेवोच्यते॥ नैष दोषः। पूर्वं हेतुरहितं व्याख्यानमुक्तम्। वृत्ताद्वेत्यनेन तु हेतुरुच्यते। तस्मिन् प्रतिपन्ने साध्यं स्वयमेवावैति॥ भाष्यकारेण वा तदुक्तम् इदं तु वार्तिककारेण॥

(उद्द्योतः) व्याख्यानाच्चेदिति। व्याख्यातारोत्र प्रत्ययादावीदृशः प्रयोग इति व्याख्यास्यन्ति। तत्र च तत्तत्कार्यं दृष्ट्वा तस्य तस्य तत्तदनुबन्धत्वं निर्णेष्यन्तीत्यर्थः॥ पूर्वं हेत्वित्यादि। अस्यायमवयव इत्यादिरूपम्॥ तस्मिन्नित्यादि। वृत्तरूपे हेतौ गुरुमुखादवगते सत्युक्तव्याख्यानविषयसाध्यं स्वयमेव जानातीत्यर्थः॥ नन्वेवं पूर्वोक्तसमर्थनरूपतया पक्षान्तरत्वाभावेन वाशब्दासामञ्जस्यमत आह—भाष्येति। वस्तुतस्तु विरम्य पाठे तस्य कर्तव्यता वुञ्छणादिसूत्रे द्वन्द्वानुपपत्तिर्बहुवचनानुपपत्तिश्चेत्यरुचेर्वार्तिककारस्य वृत्ताद्वेति परिहारान्तरम्। तत्रैकान्तपक्षेऽसन्देहाय व्याख्यानं शरणमित्युक्तं भाष्यकृतेति न पौनरुक्त्यशङ्केति ध्येयम्॥

(आक्षेपभाष्यम्)

युक्तं पुनर्यद् वृत्तनिमित्तको नामानुबन्धः स्यात्, नानुबन्धनिमित्तकेन नाम वृत्तेन भवितव्यम्॥

(समाधानभाष्यम्)

वृत्तनिमित्तक एवानुबन्धः। वृत्तज्ञो ह्याचार्योऽनुबन्धानासजति॥

(आक्षेपभाष्यम्)

उभयमिदमनुबन्धेषूक्तमेकान्ता अनेकान्ता इति। किमत्र न्याय्यम्?।

(समाधानभाष्यम्)

एकान्ता इत्येव न्याय्यम्॥ कुत एतत्?। अत्र हि हेतुर्व्यपदिष्टः। यच्च नाम सहेतुकं तन्न्याय्यम्॥

(उद्द्योतः) भाष्ये—एकान्ता इत्येव न्याय्यमिति। अनवयवत्वे णशकानां णादेरित्त्वानापत्तिः प्रत्ययादित्वाभावात्। एवमन्त्यत्वाभावादिशादेः शस्येत्त्वानापत्तिः। अन्त्यादिशब्दयोः परपूर्वसमीपबोधकत्वे लक्षणैव दोषः। किं च दध्नचश्चस्य वैयर्थ्यापत्तिः। वुञ्छण्कठजितिविहितके णित्त्वप्रयुक्तवृद्ध्यापत्तिश्चेति भावः॥

(आक्षेपभाष्यम्)

ननु चोक्तम् * तत्रासरूपसर्वादेशदाप्प्रतिषेधे पृथक्त्वनिर्देशोनाकारान्तत्वाद् * इति॥

(समाधानभाष्यम्)

असरूपविधौ तावन्न दोषः। आचार्यप्रवृत्तिर्ज्ञापयति—'नानुबन्धकृतमसारूप्यं भवति' इति, यदयं ददातिदधात्योर्विभाषां शास्ति॥

यदप्युक्तम्—'सर्वादेश' इति। तत्राप्याचार्यप्रवृत्तिर्ज्ञापयति—'नानुबन्धकृतमनेकाल्त्वं भवति' इति, यदयं 'शित्सर्वस्य' इत्याह॥

यदप्युक्तम्—'दाप्प्रतिषेधे पृथक्त्वनिर्देशः कर्तव्यः' इति। न कर्तव्यः। आचार्यप्रवृत्तिर्ज्ञापयति—'नानुबन्धकृतमनेजन्तत्वं भवति' इति, यदयम् "उदीचां माङो व्यतीहारे" इति मेङः सानुबन्धकस्यात्त्वभूतस्य ग्रहणं करोति॥ तस्य लोपः॥ ९॥

(प्रदीपः) मेङइति। यद्यप्यनेकान्तपक्षस्यापि ज्ञापकमेतद्याख्यातुं युज्यते तथापि हेतुरहितत्वादिहानेकान्तपक्षो भाष्यकृता त्यक्तः॥ प्रदेशान्तरे त्वनेकान्तपक्षेणापि व्यवह्रियते—* सिद्धमनुबन्धस्यानेकान्तत्वात् * इति॥ ९॥

(उद्द्योतः) हेतुरहितत्वादित्युपलक्षणम्॥ प्रदेशान्तरेषु त्विति। एवं च तत्र सैकदेश्युक्तिरिति भावः॥ ९॥

(१२८ यथासंख्यपरिभाषासूत्रम् ॥ १।३।१ आ. ७ सू.)

१५७ यथासंख्यमनुदेशः समानाम्

॥ १ । ३ । १० ॥

(प्रदीपः) यथासंख्यम् ॥१०॥ संख्यानं गणनमुच्यते। अनुदेशशब्दस्य सम्बन्धिशब्दत्वादुद्देश्याक्षिप्तः। तेनायमर्थः समानां समसंख्यानां मध्ये यथागणनमुद्देशिभिः स नुदेशिनः सम्बध्यन्ते।

(उद्द्योतः) यथासंख्य ॥ १० ॥ संख्याशब्दस्यैकत्वादिरूढस्य ग्रहणे वाक्यार्थानुपपत्तिरतो यौगिक इति व्याचष्टे—संख्यानमिति। गणनं, तत्क्रम इत्यर्थः। सूत्रे अनुदेशः पश्चादुच्चार्यमाणसंबन्धः। अत्रोद्देश्यनुदेशिन उच्चार्यमाणा उच्चार्यमाणप्रतिपाद्याश्च। उद्देश्यनुदेशिशब्दौ पूर्वोच्चार्यमाणपश्चादुच्चार्यमाणपरौ, न तूद्देश्यविधेयपरौ 'असूर्यललाटयोरित्यादौ यथासंख्यानापत्तेः ॥ समशब्दो न सर्वपर्यायः तुल्यापत्तेः किंतु संख्यासाम्यपरः ॥

(उदाहरणाधिकरणम्)

(आक्षेपभाष्यम्)

किमिहोदाहरणम्?।

(उदाहरणभाष्यम्)

"इको यणचि" दध्यत्र मध्वत्र ॥

(प्रदीपः) **इको यणचीति।** इक्शब्देन चत्वारः स्थानिनः प्रत्याय्यन्ते, यण्शब्देनापि चत्वार आदेशा इत्यर्थतोऽस्ति संख्यासाम्यम्। पश्चात्तु यद्यपीकारादिभिर्बहूनां ग्रहणाद्वैषम्यं तथापि प्रथमतोऽस्त्येव संख्यासाम्यम् ॥

(उद्द्योतः) नन्विक्शब्देन षट्पञ्चाशेर्यण्शब्देन सप्तानां चोपस्थित्या संख्यासाम्याभावात्कथं यथासंख्यमत आह—इक्शब्देनेति ॥ पश्चात्त्विति। इक्पदोपस्थितेकारादिभिर्गृहीततदीर्घादिघटितवाक्यार्थबोधे इत्यर्थः ॥ वस्तुतस्तेषामनुच्चारितत्वेन न ग्राहकत्वं किंत्विक्शब्दादिनेकत्वेन यणत्वेन चाहुयणित्यादौ तत्तद्व्यक्तिविशेषणतया गृहीतजातिचतुष्टयोपस्थितिरिति यथासंख्यनिर्वाहः ॥ पश्चात् प्रथमत इत्यादि तु चिन्त्यमेव ॥ न च जातिपक्षे सावर्ण्येन ऋकारलृकारयोः परस्परमत्यतिदेश एव वाच्य इति ऋकारस्य लकारापत्तिः। ऋदित्लदिदिति भेदेन निर्देशेन तदतिदेशानित्यत्वेनादोषापादनभिधानादेति बोध्यम् ॥

(उदाहरणबाधकभाष्यम्)

नैतदस्ति। स्थानेन्तरतमेनाप्येतत्सिद्धम् ॥ कुत आन्तर्यम्? । तालुस्थानस्य तालुस्थान ओष्ठस्थानस्यौष्ठस्थानो भविष्यतीति ॥

(उद्द्योतः) भाष्ये स्थानेन्तरतमेनापीति स्थानेन्तरतमपदघटितेन सूत्रेणेत्यर्थः ॥

(उदाहरणभाष्यम्)

इदं तर्हि "तस्थस्थमिपां तांतंतामः" इति ॥

(प्रदीपः) इदं तर्हीति। नात्र स्थानकृतमान्तर्यमस्ति। नाप्यादेशप्रकृतिकालेयर्थकृतान्तर्यसम्प्रत्ययः। प्रकृतानामादेशानां स्थान्यर्थाभिधानात् ॥

(उद्द्योतः) नन्वत्राप्यर्थत आन्तर्यादेव सिद्धमत आह—नापीति। विशिष्यार्थापरिज्ञानादिति भावः ॥

(उदाहरणबाधकभाष्यम्)

ननु चैतदपि स्थानेन्तरतमेनैव सिद्धम् ॥ कुत आन्तर्यम्? । एकार्थस्यैकार्थो द्व्यर्थस्य द्व्यर्थो बह्वर्थस्य बह्वर्थो भविष्यतीति ॥

(प्रदीपः) ननु चेति। नित्यानां शब्दानां प्रयोगादर्थकृतमान्तर्यमस्त्येवेति भावः ॥

(उद्द्योतः) लक्षणशरणानां प्राक् शास्त्रात् प्रयोगाज्ञानेनार्थविशेषनिर्णयो दुर्लभोत आह—नित्यानामिति। साधुत्वमात्रं शास्त्रैकगम्यं प्रयोगतदर्थज्ञानं तु प्राक् शास्त्रादप्यस्त्येव पाणिनेः। अन्येषां तु व्याख्यानान्नदोष इति भावः ॥

(उदाहरणभाष्यम्)

इदं तर्हि "तूदीशलातुरवर्मतीकूचवाराड्ढक्छण्ढञ्यकः" इति।

(सूत्रप्रयोजनाधिकरणम्)

(आक्षेपभाष्यम्)

किमर्थमिदमुच्यते? ॥

(प्रदीपः) **किमर्थमिति।** पाठक्रमेणैव संबन्धो भविष्यतीति भावः ॥

(उद्द्योतः) पाठेति। लोकसिद्धस्यानाख्यप्रमाणेनैव शत्रुं मित्रं विपत्तिं च जय रक्षय भञ्जयेतिवत् सिद्धिरिति भावः ॥

(८५६ समाधानवार्तिकम् ॥ १ ॥)

॥ * ॥ संज्ञासमासनिर्देशात्सर्वप्रसङ्गोऽनुदेशस्य तत्र यथासंख्यवचनं नियमार्थम् ॥ * ॥

संज्ञया समासैश्च निर्देशाः क्रियन्ते। संज्ञया तावत्—"परस्मैपदानां णलतुसुस्थलथुसणल्वमाः" इति। समासैः—"तूदीशलातुरवर्मतीकूचवाराड्ढक्छण्ढञ्यकः" इति। संज्ञासमासनिर्देशादेतस्मात्कारणात् सर्वप्रसङ्गः सर्वस्योद्देशस्य सर्वोऽनुदेशः प्राप्नोति। इष्यते च समसंख्यं यथा स्यादिति। तच्चान्तरेण यत्नं न सिध्यतीति तत्र यथासंख्यवचनं नियमार्थम्। एवमर्थमिदमुच्यते ॥

(प्रदीपः) संज्ञासमासनिर्देशादिति। परस्मैपदानां णलतुसित्यत्र संज्ञया सर्वे युगपत्प्रत्याय्यन्ते इति नास्ति पाठक्रमाव्यवस्था। लोकेप्यजाविधनौ देवदत्तयज्ञदत्तौ

विति समासनिर्देशे नास्ति क्रमनियमः । द्वन्द्वेऽनेकावयवात्मकः समुदाय एकेनैव शब्देन प्रत्याय्यत इति कुतः क्रमनियमः स्यात् ॥

(उद्द्योतः) **युगपदिति** । परस्मैपदत्वेनेत्यर्थः । एवं च क्रमो नास्तीति भावः । यद्यपि संज्ञा प्रत्येकं पर्याप्तेति न संज्ञाकृतं युगपत्प्रत्यायनं किं त्वेकशेषप्रभावलभ्यं तद् ब्राह्मणानामर्घपाद्याचमनीयानीतिवत् । तत्र ब्राह्मणत्रित्वेपि नार्घादीनां क्रमनियमस्तथापि संज्ञाया नवकसाधारण्यमेव तत्र मूलमिति संज्ञानिर्देशादित्युक्तम् ॥ **एकेनैवेति** । अवयवानां समुदायोपसर्जनतया समुदायस्यैव पदान्तरार्थेनान्वयादिति भावः ॥ समासेनैकोपस्थितेः पृथगुपस्थित्यभावेन तथान्वयो वक्तुमशक्य इति तत्त्वम् ॥ भाष्ये—**सर्वस्योद्देशस्येति** । सर्वस्योद्देशिन इत्यर्थः ॥ **सर्वोनुदेश इति** सर्वेनुदेशिन इत्यर्थः ॥

(आक्षेपभाष्यम्)

किं पुनः कारणं संज्ञया च समासैश्च निर्देशाः क्रियन्ते ? ॥

(प्रदीपः) **किं पुनरिति** । तिपो णल् तसोतुसित्यादि कस्मान्न क्रियत इति प्रश्नः ॥

(उद्द्योतः) **तिपो णलिति** । यद्यप्येषापि स्वरूपमिति संज्ञा तथापि संज्ञाशब्दो बहूनां युगपत्प्रत्यायको यः शब्दस्तत्पर इति भावः ॥

(८५७ समाधानवार्तिकम् ॥ २ ॥)

॥ * ॥ संज्ञासमासनिर्देशः पृथग्विभक्तिसंज्ञ्यनुचारणार्थः ॥ * ॥

(भाष्यम्) **संज्ञया च समासैश्च निर्देशाः क्रियन्ते पृथग्विभक्तीः संज्ञिनश्च मोच्चीचरमिति ।**

(८५८ प्रयोजनान्तरवार्तिकम् ॥ ३ ॥)

॥ * ॥ प्रकरणे च सर्वसंप्रत्ययार्थः ॥ * ॥

(भाष्यम्) **प्रकरणे च सर्वेषां संप्रत्ययो यथा स्याद् "विदो लटो वा" इति ॥**

(प्रदीपः) **विदो लटो वेति** । पृथग्निर्देशे क्रियमाणे मसो म इत्येवानन्तरोऽनुवर्त्येतेत्यर्थः । व्यवहितानामपि स्वरितत्वादनुवृत्तावाश्रीयमाणायां प्रतिपत्तिगौरवप्रसङ्गः ॥

(उद्द्योतः) **प्रतिपत्तीति** । स्वरितत्वस्य लक्ष्यसिद्ध्यनुमेयतया विना शास्त्रमस्मदादिभिर्दुर्ज्ञेयत्वादिति भावः । संज्ञया समासेन च निर्देशे सति तस्यैवोत्तरसूत्रेनुवृत्तेर्न दोष इति तात्पर्यम् । एवं चैतत्सूत्रारम्भसामर्थ्याद् सूत्रान्तरस्थमुपसर्जनावयवकृतं च क्रमं गृहीत्वा यथासंख्यप्रवृत्तिरिति तत्त्वम् ॥ अत्र वदन्ति—यद्यपि समासत उपस्थितिरेकैव तथाप्येतत्सूत्रारम्भसामर्थ्यात् पृथग्वाक्यकल्पनया बोधान्तरं कल्प्यते । एवं चेदं सूत्रं द्वन्द्वसमासनिर्दिष्टसंबन्धिनोस्तथान्वयेपि द्वन्द्वस्य साधुत्वं बोधयति स्वशास्त्रे, तेन लोके आनन्तौ वर्णानां विप्रशूद्राविलादेः साधुत्वं नेति ॥

(संख्यातानुदेशविषयनिर्णयाधिकरणम्)

(आक्षेपभाष्यम्)

किं पुनः शब्दतः साम्ये संख्यातानुदेशो भवत्याहोस्विदर्थतः ? ।

(प्रदीपः) **किं पुनरिति** । यद्यप्यर्थे शब्दस्य गुणभावादर्थत एव साम्यं न्याय्यं तथापि शब्दधर्मेणाप्यर्थस्य व्यपदेशो दृश्यते यथा भ्रमरशब्दस्य द्विरेफत्वाद्विरेफो भ्रमरः । तथा ध्यक्षरं मांसं ध्यक्षरमस्थि । तस्माच्छब्दतोपि साम्यमत्राशङ्कितम् ॥

(उद्द्योतः) **शब्दधर्मेणापीति** । वाच्यवाचकयोरभेदोपचारादिति भावः ॥

(भाष्यम्) **कश्चात्र विशेषः ?** ।

(८५९ शब्दसाम्यपक्षेदूषणवार्तिकम् ॥ ४ ॥)

॥ * ॥ संख्यासाम्यं शब्दतश्चेण्णलादयः परस्मैपदानां डारौरसः प्रथमस्यायवायाव एच इत्यनिर्देशः ॥ * ॥

(भाष्यम्) **संख्यासाम्यं शब्दतश्चेण्णलादयःपरस्मैपदानां डारौरसः प्रथमस्यायवायाव एच इत्यनिर्देशः अगमको निर्देशोऽनिर्देशः । "परस्मैपदानां णलतुसुस्थलथुसणल्वमाः" इति णलादयो बहवः, परस्मैपदानामित्येकः शब्दः, वैषम्यात्संख्यातानुदेशो न प्राप्नोति ॥ डारौरसः प्रथमस्य—डारौरसो बहवः, प्रथमस्येत्येकः शब्दः, वैषम्यात् संख्यातानुदेशो न प्राप्नोति ॥ "एचोऽयवायावः" अयवायावो बहवः, एच इत्येकः शब्दः वैषम्यात् संख्यातानुदेशो न प्राप्नोति ।**

(प्रदीपः) **णलादय इति** । परस्मैपदशब्देन प्रकृतानामेव नवानां ग्रहणं न तु शतृक्वस्वोरित्यर्थतः साम्यमस्ति, न तु शब्दतः ॥ **डारौरस इति** । यदा डारौरसश्च डारौरसश्चेत्येकशेषः क्रियते तदार्थतः संख्यासाम्यमस्ति ॥ **अगमक इति** । संख्यासाम्यस्यानवबोधक इत्यर्थः ॥

(उद्द्योतः) ननु शब्दतः संख्यया समानां योनुदेशः पश्चादुच्चार्यमाणसंबन्धः स यथासंख्यमिति सूत्रार्थे **परस्मैपदानामित्यादौ** तादृशानां पश्चादुच्चार्यमाणसंबन्ध एव नेति क यथासंख्याप्राप्तिरतो व्यत्ययेन पठति—**णलादय इति** । विधेयताप्रतीतौ तु न पश्चात्त्वं नियामकं, **लोपो व्योरित्यादौ** व्यभिचारादिति भावः ॥ **ननु शतृक्वस्वोरिति** । व्याख्यानादिति भावः । अन्यथा शतृक्वसुभ्यामेकादश परस्मैपदशब्दार्था इत्यर्थतः साम्येपि न यथासंख्यं स्यादिति तात्पर्यम् ॥ **न तु शब्दत इति** । यद्यप्येक एव द्वन्द्वो युगपदेवानेकोपस्थितिजनक इत्यस्ति शब्दतः साम्यं, तथापि प्रत्येक-

पदशक्तिज्ञानसहकारेणैव स तथेति नास्ति शब्दतः साम्यम् । परस्मैपदानामित्यत्र त्वेकशेषेपि श्रूयमाणैकपदशक्त्यैव नवकोपस्थितिरिति भावः ॥ ननु परस्मैपदात्मनेपदभेदात् प्रथमाः षडित्यर्थपक्षेपि न साम्यमत आह—यदेति । भाष्ये अगमकं इति । अनिर्देश इत्यत्र मध्यमपदलोपी समास इति भावः ॥ ननु स्थान्यादेशभावावगतिरस्त्येवेत्यत आह—संख्येति ॥

(अर्थसाम्यपक्षाङ्गीकारभाष्यम्)

अस्तु तर्ह्यर्थतः ।

(८६० अर्थसाम्यपक्षदूषणवार्तिकम् ॥ ५ ॥)

॥ * ॥ अर्थतश्चेल्लृलुटोर्नन्द्यरीहणसिन्धुतक्षशिलादिषु दोषः ॥ * ॥

(भाष्यम्) अर्थतश्चेल्लृलुटोर्नन्द्यरीहणसिन्धुतक्षशिलादिषु दोषो भवति । "स्यतासी लृलुटोः" स्यतासी द्वौ, लृलुटोरित्यस्य त्रयोर्थाः । वैषम्यात्संख्यातानुदेशो न प्राप्नोति ॥

"नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः" नन्द्यादयो बहवः, ल्युणिन्यचस्त्रयः । वैषम्यात्संख्यातानुदेशो न प्राप्नोति ॥

अरीहणादयो बहवः, वुञादयः सप्तदश, वैषम्यात्संख्यातानुदेशो न प्राप्नोति ॥

"सिन्धुतक्षशिलादिभ्योऽणञौ" सिन्धुतक्षशिलादयो बहवः, अणञौ द्वौ, वैषम्यात्संख्यातानुदेशो न प्राप्नोति ॥

(प्रदीपः) लृलुटोरिति । लृशब्दस्य लृङ्लृटावर्थाविति साम्याभावः । यदा तु लृरूपं सामान्यमर्थो लृशब्दस्येति पक्षस्तदास्त्येव साम्यमिति दोषाभावः ॥ नन्यादिष्वप्यवयवेन विग्रहः समुदायः समासार्थ इत्याश्रीयमाणे समुदायत्रयापेक्षया प्रत्ययत्रयस्य साम्यसद्भावाददोषः ॥

(उद्द्योतः) सामान्यमिति । लृत्वजातिपरो निर्देशः । अत एव द्विवचनसङ्गतिरिति भावः ॥ समुदाय इति । समुदायत्रयमित्यर्थः । प्रत्ययोत्पत्तिस्तु समुदायस्याप्रयोगात् प्रत्यवयवं पर्यवस्यतीति भावः ॥

(८६१ अर्थसाम्यपक्षदूषणान्तरवार्तिकम् ॥ ६ ॥)

॥ * ॥ आत्मनेपदविधिनिष्ठासार्वधातुकद्विग्रहणेषु ॥ * ॥

(भाष्यम्) आत्मनेपदविधिनिष्ठासार्वधातुकद्विग्रहणेषु च दोषो भवति ॥ आत्मनेपदविधिश्च न सिध्यति—"अनुदात्तङित आत्मनेपदम्" अनुदात्तङितौ द्वौ, आत्मनेपदमित्यस्य द्वावर्थौ, तत्र संख्यातानुदेशः प्राप्नोति ॥

निष्ठा—"रदाभ्यां निष्ठातो नः पूर्वस्य च दः" इति रेफदकारौ द्वौ, निष्ठेत्यस्य द्वावर्थौ, तत्र संख्यातानुदेशः प्राप्नोति ॥

सार्वधातुकद्विग्रहणेषु च दोषो भवति—"श्नसोरल्लोपः" श्नमस्ती द्वौ, सार्वधातुकमित्यस्य द्वावर्थौ, तत्र संख्यातानुदेशः प्राप्नोति ॥

(प्रदीपः) आत्मनेपदेति । नन्वात्मनेपदसंज्ञा न तङ्शब्दस्य किं तु तत्प्रत्यायितानां नवानां तादीनामिति नास्त्यर्थतः साम्यम् । नैष दोषः । तद्रूपापन्नास्तादय आत्मनेपदशब्देन प्रत्याय्यन्त इत्यस्ति साम्यम् ॥ सार्वधातुकद्विग्रहणेष्विति । द्वौ गृह्येते येषु तानि द्विग्रहणानि सार्वधातुकस्य द्विग्रहणानीति समासः । सार्वधातुकमपि तेषु गृह्यत इति तेन विशेष्यन्ते ॥

(उद्द्योतः) तद्रूपापन्ना इति । संज्ञाशब्दे स्वरूपस्य प्रवृत्तिनिमित्तत्वाद् एकतङ्शब्दरूपिततया तङ्त्वेनैवोपस्थितानां संज्ञेति संज्ञासूत्रस्यमार्थं साम्यमादाय स्याद्यथासंख्यमिति भावः ॥ क्वचित्तु तङ्रूपापन्ना इत्येव पाठः ॥ ननु यत्र द्वावुपादीयेते श्नमस्ती सार्वधातुकग्रहणं चास्ति तत्र न स्यादिति वक्तव्येऽगमकोयं निर्देशोऽत आह—द्वाविति । अधिकरणसाधनग्रहणशब्देन द्विशब्दस्य षष्ठीसमासस्ततः पुनः सार्वधातुकपदेन स इति भावः ॥ सार्वधातुकपदेन षष्ठीसमासे षष्ठीप्रयोजकसंबन्धं दर्शयति—सार्वधातुकमपीति ।

(८६२ आक्षेपवार्तिकम् ॥ ७ ॥)

॥ * ॥ एङः पूर्वत्वे प्रतिषेधः ॥ * ॥

(भाष्यम्) एङः पूर्वत्वे प्रतिषेधो वक्तव्यः । "एङः पदान्तादति" "ङसिङसोश्च" ङसिङसौ द्वौ, एङित्यस्य द्वावर्थौ, तत्र संख्यातानुदेशः प्राप्नोति ॥

(शब्दसाम्यपक्षाभ्युपगमभाष्यम्)

अस्तु तर्हि शब्दतः ॥

(उद्द्योतः) अथ शब्दतः साम्ये उक्तदोषोद्धारमाह—भाष्ये—अस्तु तर्हीति ॥

(आक्षेपभाष्यम्)

ननु चोक्तं *संख्यासाम्यं शब्दतश्चेण्णलादयः परस्मैपदानां डारौरसः प्रथमस्यायवायाव एच इत्यनिर्देशः* इति ॥

(समाधानभाष्यम्)

नैष दोषः । "स्थानेऽन्तरतम" इत्यनेन व्यवस्था भविष्यति ॥ कुत आन्तर्यम्? । एकार्थस्यैकार्थो द्व्यर्थस्य द्व्यर्थो, बह्वर्थस्य बह्वर्थः । संवृतावर्णस्य संवृतावर्णः, विवृतावर्णस्य विवृतावर्णः ॥

(प्रदीपः) **संवृतावर्ण इति।** यद्यपि शास्त्रेऽकारस्य विवृतोपदेशः कृतस्तथापि लौकिकप्रयोगापेक्षयैतदुक्तम् ॥

(उद्योतः) **एकार्थस्येत्यादि ।** प्रत्यक्त्वादिकमप्युपलक्ष्यतेनेनेति बोध्यम् ॥ **यद्यपीति** । एवं च संवृतावर्णस्येत्ययुक्तमिति भावः ॥ **लौकिकेति ।** केचित्तु ए ओ इत्यनयोः संवृतावर्णत्वे मानाभावः । ह्रस्वाकारव्यतिरिक्तानां विवृतत्वस्यैवाइउण्सूत्रेभाष्ये उक्तत्वात् प्रत्यापत्तिशास्त्रस्यावयवे प्रवृत्तौ मानाभावाच्च शास्त्रदृष्टया तस्यासिद्धत्वाच्च चिन्त्यमिदमित्याहुः ॥ अन्येत्वेतद्भाष्यप्रमाण्याद् ए ओ इत्यनयोरकारांशे संवृतत्वमेवेतरांशे एव विवृतत्वम् । तदुपरागाच्च न संवृतत्वस्य लोके प्रयोगे स्पष्टमवभासः । ऐ औ इत्येतयोस्त्वकारांशेपि विवृतत्वमेवेत्याहुः ॥

(८६३ आक्षेपवार्तिकम् ॥ ८ ॥)

॥ * ॥ अतिप्रसङ्गो गुणवृद्धिप्रतिषेधे क्ङिति ॥ * ॥

(भाष्यम्) **अतिप्रसङ्गो भवति गुणवृद्धिप्रतिषेधे क्ङिति। गुणवृद्धी द्वे, क्ङितौ द्वौ, तत्र संख्यातानुदेशः प्राप्नोति ॥**

(प्रदीपः) **क्ङितौ द्वाविति ।** क्ङिच्छब्दस्यैकत्वेपि ककारङकारयोर्द्वित्वादस्ति शब्दतः साम्यम् ॥

(उद्योतः) अतिप्रसङ्ग इत्यादिना वक्ष्यमाणदोषाणां साधारणत्वाद्बाधदोषः शब्दसाम्यपक्षे नारोहतीत्यतस्तं तत्रोपपादयति—**क्ङिच्छब्दस्येति** ॥

(समाधानभाष्यम्)

नैष दोषः। गकारोप्यत्र निर्दिश्यते ॥

(उद्योतः) भाष्ये—**गकारोपीति ।** स्थास्नुरित्यत्रेत्त्वाभावाय क्स्नोर्गित्त्वावश्यकत्वेन जिष्णुरित्यत्र गुणाभावाय तन्निर्देश इति भावः ॥

(तटस्थभाष्यम्)

तद्गकारग्रहणं कर्तव्यम् ॥

(सिद्धान्तिभाष्यम्)

न कर्तव्यम्। क्रियते न्यास एव। ककारे गकारश्चर्त्वभूतो निर्दिश्यते गिति किति ङितीति ॥

(८६४ आक्षेपवार्तिकम् ॥ ९ ॥)

॥ * ॥ उदिकूले रुजिवहोः ॥ * ॥

(भाष्यम्) **उदिकूले द्वे, रुजिवहौ द्वौ, तत्र संख्यातानुदेशः प्राप्नोति ॥**

(प्रदीपः) **उदिकूल इति ।** द्वन्द्वोयम् आगन्तुना चेकारेण निर्देश इति चोद्यम् ॥

(उद्योतः) उत्कूले द्वे इति वाच्ये उदिकूले इति इकारसहितः पाठो व्याख्यानभाष्येऽयुक्त इत्यत आह—**आगन्तुनेति** ॥ वस्तुत उदि कूले इत्यनुकरणम् । इति द्वे शब्दरूपे इत्यर्थे इति न दोषः ॥

(आक्षेपदूषकभाष्यम्)

नैष दोषः। नोदिरुपपदम् ॥ किं तर्हि ?। विशेषणं रुजिवहोः। उत्पूर्वाभ्यां रुजिवहिभ्यां कूल उपपद इति ॥

(प्रदीपः) उदीति पञ्चम्याः स्थाने सप्तमी कृता। उदः पराभ्यां रुजिवहीभ्यामिति परिहारः ॥

(उद्योतः) सप्तमीविभक्तिसाम्येऽर्थवैरूप्यमनुपपन्नमत आह—**उदीतीति।** एवं रुजिवहोरित्यपि पञ्चम्याः स्थाने षष्ठीति बोध्यम् ॥

(८६५ आक्षेपवार्तिकम् ॥ १० ॥)

॥ * ॥ तच्छीलादिषु धातुत्रिग्रहणेषु ॥ * ॥

(भाष्यम्) **तच्छीलादिषु धातुत्रिग्रहणेषु दोषो भवति ॥ "विदिभिदिच्छिदेः कुरच्" विदिभिदिच्छिदयस्त्रयः, तच्छीलादयस्त्रयः, तत्र संख्यातानुदेशः प्राप्नोति ॥**

(प्रदीपः) **धातुत्रिग्रहणेष्विति ।** त्रीणि ग्रहणानि येषां ते त्रिग्रहणा धातवस्त्रिग्रहणा येषु तच्छीलादिषु इति पुनर्बहुव्रीहिः ॥

(८६६ आक्षेपवार्तिकम् ॥ ११ ॥)

॥ * ॥ घञादिषु द्विग्रहणेषु ॥ * ॥

(भाष्यम्) **घञादिषु द्विग्रहणेषु दोषो भवति। "निरभ्योः पूल्वोः" निरभी द्वौ, पूल्वौ द्वौ, तत्र संख्यातानुदेशः प्राप्नोति ॥**

(आक्षेपनिराकरणभाष्यम्)

नैष दोषः। इष्यते चात्र संख्यातानुदेशः निष्पावः अभिलाव इति ॥

(आक्षेपव्याख्यान्तरभाष्यम्)

एवं तर्हि अकर्तरि च कारके भावे चेति द्वौ, पूल्वौ द्वौ, तत्र संख्यातानुदेशः प्राप्नोति ॥

(उद्योतः) भाष्ये—**एवं तर्ह्यकर्त्तरि चेति ।** विशेषणविशेष्यभावापन्नार्थवाचकत्वादकर्त्तरि कारक इत्येकशब्दो, भाव इत्यपर

इति शब्दतः साम्ये एष दोषः । अर्थतः साम्यं तु न कारकाणां बहुत्वादिति बोध्यम् ॥

(८६७ आक्षेपवार्तिकम् ॥ १२ ॥)

॥ * ॥ अवे तृस्त्रोः करणाधिकरणयोः ॥ * ॥

(भाष्यम्) तृस्त्रौ द्वौ, करणाधिकरणे द्वे, तत्र संख्यातानुदेशः प्राप्नोति ॥

(८६८ आक्षेपवार्तिकम् ॥ १३ ॥)

॥ * ॥ कर्तृकर्मणोश्च भूकृञोः ॥ * ॥

(भाष्यम्) कर्तृकर्मणी द्वे, भूकृञौ द्वौ, तत्र संख्यातानुदेशः प्राप्नोति ॥

(प्रदीपः) कर्तृकर्मणोरिति । भवतेरकर्मकत्वात्कर्तृबोपपदम् । करोतेस्तूपपदद्वये खलिष्यते ॥ अन्ये तु प्राप्त्यर्थस्य भवतेरुपपदद्वये प्रत्ययमिच्छन्ति ॥

(उद्योतः) ननु भवतेरकर्मकत्वात्कर्तर्येव, करोतेस्तु सकर्मकत्वात्कर्मण्येवेति यथासंख्यमिष्टमेवेति भ्रमं वारयति—भवतेरिति ॥ अन्ये त्विति । अत एव—

"हृतदारतयाऽतिकोपनः शरणं किं रघुपुंगवो भवेत् ।
इति रावण मा कृथा मतिं स किलेशः शरणंभवो विभुः" इति 'तांकिताशरणताकः सुखेन शरणत्वेन प्राप्य' इत्यर्थकमुपपन्नमिति भावः ॥

(८६९ आक्षेपवार्तिकम् ॥ १४ ॥)

॥ * ॥ अनवक्लृप्त्यमर्षयोरकिंवृत्तेपि ॥ * ॥

(भाष्यम्) अनवक्लृप्त्यमर्षौ द्वौ, किंवृत्ताकिंवृत्ते द्वे, तत्र संख्यातानुदेशः प्राप्नोति ॥

(८७० आक्षेपवार्तिकम् ॥ १५ ॥)

॥ * ॥ कृभ्वोः क्त्वाणमुलौ ॥ * ॥

(भाष्यम्) कृभ्वौ द्वौ, क्त्वाणमुलौ द्वौ, तत्र संख्यातानुदेशः प्राप्नोति ॥

(८७१ आक्षेपवार्तिकम् ॥ १६ ॥)

॥ * ॥ अधीयानविदुषोश्छन्दोब्राह्मणानि ॥ * ॥

(भाष्यम्) छन्दोब्राह्मणानीति द्वे, अधीते वेदिति च द्वौ, तत्र संख्यातानुदेशः प्राप्नोति ॥

(प्रदीपः) छन्दोब्राह्मणानीति । गोबलीवर्दन्यायेन छन्दःशब्देन मन्त्राणां ग्रहणम् । यथा जुष्टार्पिते च छन्दसीति ब्राह्मणानां ग्रहणं नित्यं मन्त्र इति मन्त्रग्रहणात् । छन्दोग्रहणेनैव तु ब्राह्मणानां ग्रहणे सिद्धे ब्राह्मणविशेषप्रतिपत्त्यर्थं पुनर्ब्राह्मणग्रहणं कृतम् । तेन याज्ञवल्कानि ब्राह्मणानीति तद्विषयता न भवति ॥

(उद्योतः) गोबलीवर्दन्यायेनेति । ब्राह्मणवसिष्ठन्यायस्योपलक्षणं गोबलीवर्दयोः सामान्यविशेषभावाभावस्यैकशेषप्रकरणान्ते भाष्ये उक्तत्वात् ॥ तथा पृथग्ब्राह्मणग्रहणे फलमाह—छन्द इति । वस्तुतो गायत्र्यादिछन्दोबद्धेषु मन्त्रेष्वेव छन्दस्त्वमिति बोधयितुं तत्र ब्राह्मणग्रहणम् । जुष्टार्पिते इत्यत्र तु छन्दःपदस्य ब्राह्मणे लक्षणेति बोध्यम् ॥ याज्ञवल्कानीत्यर्थं तु *याज्ञवल्क्यादिभ्यः प्रतिषेधः* इति वचनमेव कृतं भाष्ये ॥ भाष्ये अधीयानविदुषोरिति । तत्र विद्वत्पर्यायो विदुषशब्दः । अन्यथा वस्वन्तस्यैतिरूपितभत्वाकत्वाभावात्तदसिद्धिरिति बोध्यम् ॥

(८७२ आक्षेपवार्तिकम् ॥ १७ ॥)

॥ * ॥ रोपधेतोः पथिदूतयोः ॥ * ॥

(भाष्यम्) "रोपधेतोः प्राचाम्, तद्गच्छति पथिदूतयोः" । रोपधेतौ द्वौ, पथिदूतौ द्वौ, तत्र संख्यातानुदेशः प्राप्नोति ॥

(८७३ आक्षेपवार्तिकम् ॥ १८ ॥)

॥ * ॥ तत्र भवस्तस्य व्याख्यानः क्रतुयज्ञेभ्यश्च ॥ * ॥

(भाष्यम्) तत्रभवस्तस्य व्याख्यानौ द्वौ, क्रतुयज्ञौ द्वौ, तत्र संख्यातानुदेशः प्राप्नोति ॥

(८७४ आक्षेपवार्तिकम् ॥ १९ ॥)

॥ * ॥ संघादिष्वञ्प्रभृतयः ॥ * ॥

(भाष्यम्) संघादिष्वञ्प्रभृतयः संख्यातानुदेशेन न सिध्यन्ति ॥

(उद्योतः) सङ्घादिष्विति । सङ्घाङ्कलक्षणेष्वञ्यञिञामणित्यत्र त्रिष्वप्यर्थेषु त्रिभ्यः प्रत्यय इष्यते तत्र संख्यातानुदेशेन त्रिष्वप्यर्थेष्वञादयोऽण्विशिष्टा न सिध्यन्तीत्यर्थः ॥

(आक्षेपवारकभाष्यम्)

नैष दोषः । घोषग्रहणमपि तत्र कर्तव्यम् ॥

(८७५ आक्षेपवार्तिकम् ॥ २० ॥)

॥ * ॥ वेशोयशआदेर्भगाद्यत्खौ ॥ * ॥

(भाष्यम्) वेशोयशआदी द्वौ, यत्खौ द्वौ, तत्र संख्यातानुदेशः प्राप्नोति ॥

(८७६ आक्षेपवार्तिकम् ॥ २१ ॥)

॥ * ॥ ङसिङसोः ख्यत्यात्परस्य ॥ * ॥

(भाष्यम्) ङसिङसौ द्वौ, ख्यत्यौ द्वौ, तत्र संख्यातानुदेशः प्राप्नोति ॥

(८७७ उक्ताक्षेपबाधकसमाधानवार्तिकम् ॥ २२ ॥)

॥ * ॥ न वा समानयोगवचनात् ॥ * ॥

(भाष्यम्) न वा एष दोषः ॥ किं कारणम्? । समानयोगवचनात् समानयोगे संख्यातानुदेशं वक्ष्यामि ॥

(प्रदीपः) न वेति । अनुदेश उच्चारणम् । योगान्तरे तु शब्दान्तरस्यानुमानं न तूच्चारणमिति न्यायप्राप्त एवायमर्थः ॥

(उद्द्योतः) वचनादिति भाष्यस्य व्याख्यानादित्यर्थ इत्याह—अनुदेश इति ॥ उच्चारणम् । उच्चारितसंबन्ध इत्यर्थः ॥ वस्तुत उच्चारितस्यैव शब्दस्य बोधकत्वं नानुमितादेरित्यणुदित्सूत्रभाष्योक्तेरनुमानपूर्वकस्योच्चारणात् श्रोतुर्बोधः ॥ समानयोग इत्यस्य चैकयोगे वक्त्रोच्चारितानामित्यर्थ इति वाचनिकमेवेदम् ॥ एतेन निरभ्योः, 'अवे तृस्त्रोः' 'स्वाङ्गे तस्प्रत्यये' 'शेषधेतोः' 'क्रतुयज्ञेभ्यः' 'ख्यत्याद्' 'अनवक्लृप्त्यमर्षयोरित्येतेषु परिहृतो दोषः । समानयोगे द्वयोरुच्चारणाभावात् । छन्दोब्राह्मणानीत्यत्रापि न दोषः । तत्पदोपस्थापितत्वेप्युच्चारणाभावात् । अत्र पक्षे 'कर्तृकर्मणोश्च भूकृञोः' 'वेशोयशआदेरित्यपरिहृते । ते च *युष्मदस्मदोश्चादेशाः* इति चेन भाष्ये संग्राह्ये ॥

(इति यथासंख्यापत्तिवारणम्)

(अथ यथासंख्यानुपपत्तिप्रकरणम्)

(८७८ आक्षेपवार्तिकम् ॥ २३ ॥)

॥ * ॥ तस्य दोषो विदो लटो वा ॥ * ॥

(भाष्यम्) तस्यैतस्य लक्षणस्य दोषः "विदो लटो वा" इति संख्यातानुदेशो न प्राप्नोति ॥

(प्रदीपः) विदो लटो वेति । अत्र तु लब्धयथासंख्यानामनुमानाददोषः ॥

(उद्द्योतः) भाष्ये—तस्य दोष इति । *समानयोगे* इत्यस्येत्यर्थः ॥ अत्र तु लब्धेति । इदं चिन्त्यम् । तत्तयोगे वक्त्रोच्चारितानामेव तथा संबन्ध इति पक्षमुपक्रम्य दोषोक्तेः ॥

(८७९ आक्षेपवार्तिकम् ॥ २४ ॥)

॥ * ॥ ध्माधेटोः नाडीमुष्टयोश्च ॥ * ॥

(भाष्यम्) ध्माधेटोः नाडीमुष्टयोश्च संख्यातानुदेशो न प्राप्नोति ॥

(उद्द्योतः) भाष्ये—नाडीमुष्टयोरिति । इदं तृतीयाध्यायस्थभाष्यविरोधादेकदेशिवचनम् ॥

(८८० आक्षेपवार्तिकम् ॥ २५ ॥)

॥ * ॥ खलगोरथादिनित्रकट्यचश्च ॥ * ॥

(भाष्यम्) संख्यातानुदेशो न प्राप्नोति ॥

(८८१ आक्षेपवार्तिकम् ॥ २६ ॥)

॥ * ॥ सिन्ध्वपकराभ्यां कन् अणञौ च ॥ * ॥

(भाष्यम्) संख्यातानुदेशो न प्राप्नोति ॥

(८८२ आक्षेपवार्तिकम् ॥ २७ ॥)

॥ * ॥ युष्मदस्मदोश्चादेशाः ॥ * ॥

(भाष्यम्) युष्मदस्मदोश्चादेशाः संख्यातानुदेशान्न सिद्ध्यन्ति ॥

(प्रदीपः) युष्मदस्मदोश्चेति । बहुवचनस्य वस्नसावित्यादिषु योगेष्वनुमीयमानत्वाद् युष्मदस्मदोर्यथासंख्यं न प्राप्नोति ॥

(उपसंहारभाष्यम्)

तस्माद्यस्मिन्पक्षेऽल्पीयांसो दोषाः, तमास्थाय प्रतिविधेयं दोषेषु ॥

(प्रदीपः) यस्मिन् पक्षइति । शब्दतः साम्यमेकयोगे चेत्येष पक्ष आश्रयितव्य इत्याहुः । दोषप्रतिविधानं तु क्वचिदान्तर्याद्व्यवस्था क्वचिदनभिधानाभिधानाभ्यामिति कर्तव्यम् ॥

(उद्द्योतः) यस्मिन् पक्षे इति । समानयोगे इत्येतत्करणाकरणपक्षयोर्मध्ये यत्र पक्षे इत्यर्थः ॥ इत्याहुरिति । अत्रारुचिबीजं तूक्तरीत्याथेत इति पक्षेपि दोषोद्धारस्य सुकरत्वात् तदनाश्रयणं किमर्थमिति ॥ क्वचिदिति । युष्मदाद्यादेशविषये, विदो लट इत्यत्र च ॥ क्वचिदिति । खलगो सिन्ध्वादौ । अत्र संख्यातानुदेशाभावेप्यभिधानात् प्रयोगानुसरणात्समासनिर्देशेपि क्रमेणान्वयः ॥ कर्तृकर्मणोश्च भू इत्यत्र वेशोयश इत्यत्र चानभिधानादेतत्सूत्राप्रवृत्तिरित्यर्थः ॥ एकयोगे इत्यस्यानाश्रयणपक्षे त्वनेकस्थलेऽनभिधानाश्रयणमिति तात्पर्यम् ॥

(समाधानान्तरभाष्यम्)

अथ वैवं वक्ष्यामि "यथासंख्यमनूदेशः समानां

स्वरितेन" ततः "अधिकारः" अधिकारश्च भवति स्वरितेनेति ॥

(प्रदीपः) **अथवेति** । यत्र स्वरितत्वं प्रतिज्ञायते तत्रैव शब्दतोऽर्थतो वा साम्याश्रयणेन यथासङ्ख्यं, नान्यत्र सत्यपि संख्यासाम्ये ॥ १० ॥

(उद्द्योतः) अस्य दुर्ज्ञेयत्वादाह—**अथ वेति** ॥ १० ॥

(आक्षेपभाष्यम्)

एवमपि स्वरितं दृष्ट्वा संदेहः स्यात्-न ज्ञायते—किमयं समसंख्यार्थः, आहोस्विदधिकारार्थ इति ?॥

(आक्षेपबाधकभाष्यम्)

संदेहमात्रमेतद्भवति । सर्वसंदेहेषु चेदमुपतिष्ठते 'व्याख्यानतो विशेषप्रतिपत्तिर्न हि संदेहादलक्षणम्' इति । समसंख्यार्थ इति व्याख्यास्यामः ॥ यथासंख्यमनुदेशः ॥ १० ॥

(१२९ परिभाषासूत्रम् ॥ १।२।१ आ० ८ सू०)

१५८ स्वरितेनाधिकारः ॥१।३।११॥

(प्रदीपः) **स्वरितेन** ॥ ११ ॥ स्वरितेनेतीत्थंभूतलक्षणे तृतीया । स्वरितेनाधिकारो लक्ष्यते इत्यर्थः । स्वरितत्वं सूत्रस्थानां केवलमधिकारज्ञानार्थं प्रतिज्ञायते, न तु प्रयोगसमवायि । अधिकारशब्दो भावसाधनः कर्मसाधनो वा । विनियोगो लोकेऽधिकार उच्यते स एवेह गृह्यते ॥

(उद्द्योतः) **स्वरितेन** ॥ ११ ॥ नेयं हेतौ तृतीया, अधिकारस्य स्वरितजन्यत्वाभावादत आह—**इत्थंभूतेति** ॥ **नत्विति** । स्वरितोच्चारणस्याधिकारज्ञापनेन चारितार्थ्यात् प्रयोगे शास्त्रान्तरप्राप्तस्वरेण बाध्यत इति भावः । न च स्वरितत्वस्याज्धर्मत्वात् **समस्सुटी**त्यादावप्रेनुवर्त्तमानहलः कथं तत्त्वम् । तत्समभिव्याहृताचि तत्करणेनादोषात् । स्पष्टं चेदं **समस्सुटी**त्यत्र कैयटे ॥ इहाधिकारो नोपक्रम इत्याह—**अधिकारेति** । प्रेरणं तद्विषयीभूतं कार्यं वा लौकिकोऽधिकारः । तत्र शब्दस्य द्विविधं कार्यम्—अर्थबोधः स्वरूपबोधो वा । तत्रार्थबोधस्य वचननिरपेक्षत्वाद् द्वितीये पर्यवसानेन योगेयोगे उपस्थानं फलति । तच्च प्राय उत्तरयोगेषु, क्वचित्पूर्वत्रापि, यथा—**संयोगान्तस्य लोपो स्कोःसंयोगाद्योरन्ते चे**त्यादाविति भावः ॥

(सूत्रप्रयोजनाक्षेपभाष्यम्)

किमर्थमिदमुच्यते ? ।

(प्रदीपः) **किमर्थमिति** । आकाङ्क्षादिवशात्प्रकृतस्य सम्बन्धो लोक इव भविष्यतीति प्रश्नः ॥

(८८३ समाधानवार्तिकम् ॥ १ ॥)

॥ * ॥ अधिकारः प्रतियोगं तस्यानिर्देशार्थः ॥ * ॥

(भाष्यम्) **अधिकारः क्रियते प्रतियोगं तस्यानिर्देशार्थ इति ॥ किमिदं प्रतियोगमिति ? । योगं योगं प्रति प्रतियोगम् । योगे योगे तस्य ग्रहणं मा कार्षमिति ॥**

(आक्षेपभाष्यम्)

किं गतमेतदियता सूत्रेण ? ।

(प्रदीपः) **किं गतमिति** । किमयमर्थोऽधिकारशब्देन परिगृहीतः, अथ नेति प्रश्नः ॥

(उद्द्योतः) उक्तार्थे सूत्रस्य समर्थत्वात्किंगतमिति प्रश्नोऽयुक्तोऽत आह—**किमयमिति** ॥ यद्यधिकारशब्देन प्रतियोगमुपस्थानमुच्यते, तदा सूत्रं सफलं स्यात् । तस्य सन्योऽर्थे इत्याक्षेप इति भावः ॥

(समाधानभाष्यम्)

गतमित्याह ॥ कुतः ? । लोकतः ॥ तद्यथा लोके—'अधिकृतोऽसौ ग्रामे' 'अधिकृतोऽसौ नगरे' इत्युच्यते यो यत्र व्यापारं गच्छति । शब्देन चाप्यधिकृतेन कोऽन्यो व्यापारः शक्योऽवगन्तुमन्यदतो योगे योग उपस्थानात् ॥

(प्रदीपः) **शब्देनेति** । नहि परिस्पन्दरूपः शब्दस्य व्यापारोऽस्ति ॥

(उद्द्योतः) **नहीति** । अर्थबोधरूपो व्यापारस्तु न वचनसाध्य इति भावः । पारिशेष्यादुपस्थानलाभ इति बोध्यम् ॥

(८८४ समाधानबाधकवार्तिकम् ॥ २ ॥)

॥ * ॥ न वा निर्दिश्यमानाधिकृतत्वाद्यथा लोके ॥ * ॥

(भाष्यम्) **न वा एतत्प्रयोजनमस्ति ॥ किं कारणम् ? । निर्दिश्यमानाधिकृतत्वात् । यथा लोके । निर्दिश्यमानमधिकृतं गम्यते । तद्यथा—'देवदत्ताय गौर्दीयताम्' 'यज्ञदत्ताय' 'विष्णुमित्राय' इति । गौरिति गम्यते । एवमिहापि "एदङ्गवि-**

शास्त्रशो घञ्" "स्तृ स्थिरे" "भावे" घञिति गम्यते ॥

(प्रदीपः) न वेति । वचनरहिताल्लोकव्यवहारादेवास्यार्थः सिद्ध इत्यर्थः ॥ यज्ञदत्तायेति । सम्प्रदानविभक्त्या सन्निहिता गोकर्मिका ददातिक्रियापेक्ष्यते । अश्रुतकल्पनायाः श्रुतापेक्षणस्य लाघवात् ॥

(उद्योतः) वचनेति । तथा च मन्त्रमेवाक्षिप्यत इत्यर्थः । संनिहिता गोकर्मिकेति ॥ गौरिति गम्यत इति भाष्यस्य गार्दीयतामिति गम्यते इत्यर्थः ॥ श्रुतापेक्षणस्येति पाठः श्रुतकल्पनस्येत्यर्थः ॥ लाघवादित्यस्य न्याय्यत्वमिति शेषः ॥

(८८५ समाधानसाधकवार्तिकम् ॥ ३ ॥)

॥ * ॥ अन्यनिर्देशस्तु निवर्तकस्तस्मात्परिभाषा ॥ * ॥

(भाष्यम्) अन्यनिर्देशस्तु लोके निवर्तको भवति। तद्यथा 'देवदत्ताय गौर्दीयताम्' 'विष्णुमित्राय कम्बलः' इति कम्बलो गोर्निवर्तको भवति। एवमिहापि "अभिविधौ भाव इनुण्" घञो निवर्तकः स्यात्। तस्मात्परिभाषा कर्तव्या ॥

(प्रदीपः) घञो निवर्तकः स्यादिति । ततश्चाक्रोशे अवन्योर्ग्रह इत्यादिष्वनन्तर इनुण् स्यात् । सति सूत्रे घञः स्वरितत्वप्रतिज्ञानादनुवृत्तिर्भवति, न त्विनुणो विपर्ययात् ॥

(उद्योतः) इनुण्विधौ घञो निवृत्तिरिष्टैवेत्यत आह—ततश्चेति ॥

(८८६ आक्षेपवार्तिकम् ॥ ४ ॥)

॥ * ॥ अधिकारपरिमाणाज्ञानं तु ॥ * ॥

(भाष्यम्) अधिकारपरिमाणाज्ञानं तु भवति। न ज्ञायते कियन्तमवधिमधिकारोनुवर्तत इति ॥

(प्रदीपः) अधिकारपरिमाणाज्ञानं त्विति । यथा धातोरिति किं प्राग्लादेशेभ्योऽध्यायपरिसमाप्तेः । अङ्गाधिकारः प्रागभ्यासविकारेभ्योथासप्तमपरिसमाप्तेरिति ॥

(उद्योतः) अधिकारपरिमाणशब्देन तत्प्रदेशपरिमाणं विवक्षितमित्याह—यथेति ॥

(८८७ समाधानवार्तिकम् ॥ ५ ॥)

॥ * ॥ अधिकारपरिमाणज्ञानार्थं तु ॥ * ॥

(भाष्यम्) अधिकारपरिमाणज्ञानार्थ एव तर्हि अयं योगो वक्तव्यः । अधिकारपरिमाणं ज्ञास्यामीति ॥

(आक्षेपभाष्यम्)

कथं पुनः "स्वरितेनाधिकार" इत्यनेनाधिकारपरिमाणं शक्यं विज्ञातुम् ? ॥

(समाधानभाष्यम्)

एवं वक्ष्यामि— "स्वरिते नाधिकारः" इति । स्वरितं दृष्ट्वाधिकारो न भवतीति ॥

(प्रदीपः) स्वरितं दृष्ट्वेति । प्रकृतस्याधिकारनिवृत्तये शब्दान्तरस्य स्वरितत्वं प्रतिज्ञायते । तेन विंशतिकात्ख इत्यत्र स्वरितत्वदर्शनाद्द्वित्रिपूर्वादित्यस्य निवृत्तिरनुमीयते ॥

(उद्योतः) प्रकृतस्येति । सूत्रे स्वरित इति सतिसप्तमीति भावः ॥

(आक्षेपभाष्यम्)

केनेदानीमधिकारो भविष्यति ? ॥

(उद्योतः) भाष्ये—केनेदानीमिति । सूत्रं अधिकारनिवृत्त्यर्थं न तु तद्बोधकमिति भावः ॥

(समाधानभाष्यम्)

लौकिकोधिकारः ॥

(८८८ व्याख्यान्तरनिरूपणवार्तिकम् ॥ ६ ॥)

॥ * ॥ नाधिकार इति चेदुक्तम् ॥ * ॥

(भाष्यम्) किमुक्तम् ? । *अन्यनिर्देशस्तु निवर्तकस्तस्मात्परिभाषा* इति ॥

(उपसंहारभाष्यम्)

अधिकारार्थमेव तर्ह्ययं योगो वक्तव्यः ॥

(आक्षेपभाष्यम्)

ननु चोक्तम्—*अधिकारपरिमाणाज्ञानं तु* इति ॥

(८८९ समाधानवार्तिकम् ॥ ७ ॥)

॥ * ॥ यावतिथोऽलनुबन्धस्तावतो योगाननिति वचनात्सिद्धम् ॥ * ॥

(भाष्यम्) यावतिथोऽलनुबध्यते तावतो योगाननधिकारोनुवर्तत इति वक्तव्यम् ॥

(प्रदीपः) यावतिथ इति । द्वित्रिपूर्वान्निष्कादित्यत्र इकारोनुबन्धः कर्तव्यः । तेन द्वयोर्योगयोरनुवृत्तिर्भवति । एवमन्यत्रापि वेदितव्यम् ॥

(उद्योतः) इकारोऽनुबन्ध इति । प्रत्याहारसूत्रस्थक्रमेणेत्यर्थः ॥

(आक्षेपभाष्यम्)

अथेदानीं यत्राल्पीयांसोऽलः, भूयसश्च योगानधिकारोनुवर्तते, कथं तत्र कर्तव्यम् ? ॥

(प्रदीपः) अल्पीयांस इति । कथं पुनर्भिन्नजातीयापेक्षया प्रकर्षप्रत्ययः ॥ परमतापेक्षया ॥ अल्पे योगा इति चेन्मन्यसे तत्राल्पीयांसोऽलः । अथ बहवोऽल इति चेद्भूयांसो योगाः ॥

(उद्द्योतः) ननु द्वयोरल्पयोरयमल्पीयानिति भवति, नवमत्रालामल्पत्वात् सूत्राणां बहुत्वादिति शङ्कते—कथमिति । भिन्नजातीयत्वं बहुत्वेन सूत्राणां बोध्यम् ॥ परिहरति—परमतेति । यावतिथोऽलिति वादी अल्पे योगा बहवोऽल इति मन्यते, आक्षेप्ता तु अल्पेऽलो बहवो योगा इति । एवं च मतभेदेनालां योगानां च प्रत्येकमल्पत्वं बहुत्वं च प्राप्तं तदवलम्ब्यात्र प्रकर्षप्रत्यय इत्यर्थः ॥

(८९० समाधानवार्तिकम् ॥ ८ ॥)

॥ * ॥ भूयसि प्राग्वचनम् ॥ * ॥

(भाष्यम्) भूयसि प्राग्वचनं कर्तव्यम् । 'प्रागमुत' इति वक्तव्यम् ॥

(प्रदीपः) भूयसीति । अङ्गस्य प्राग्द्वेरित्यादि वक्तव्यम् ॥

(उद्द्योतः) प्राग् द्वेरिति । सर्वस्य द्वे इति द्विशब्दात्प्रागित्यर्थः ॥

(आक्षेपभाष्यम्)

तत्तर्हि वक्तव्यम् ॥

(प्रदीपः) तत्तर्हीति । यावतिथोऽलिति भूयसि प्राग्वचनं चेत्यर्थः ॥

(उद्द्योतः) यावतिथ इति । समुदायाभिप्रायं तत्तर्हीत्येकवचनमिति भावः ॥

(समाधानभाष्यम्)

न वक्तव्यम् । संदेहमात्रमेतद्भवति । सर्वसंदेहेषु चेदमुपतिष्ठते—"व्याख्यानतो विशेषप्रतिपत्तिर्नहि संदेहादलक्षणम्" इति । प्रागमुत इति व्याख्यास्यामः ॥

(प्रत्याख्यानभाष्यम्)

यद्येवं नार्थोनेन ॥

(आक्षेपभाष्यम्)

केनेदानीमधिकारो भविष्यति ? ॥

(समाधानभाष्यम्)

लौकिकोधिकारः ॥

(आक्षेपभाष्यम्)

ननु चोक्तं—*नाधिकार इति चेदुक्तम् * । किमुक्तम् ? । * अन्यनिर्देशस्तु निवर्तकस्तस्मात्परिभाषा* इति ॥

(समाधानभाष्यम्)

संदेहमात्रमेतद्भवति । सर्वसंदेहेषु चेदमुपतिष्ठते 'व्याख्यानतो विशेषप्रतिपत्तिर्नहि संदेहादलक्षणम्' इत्युक्तम् ॥ इनुण्घञिति संदेहे घञिति व्याख्यास्यामः ॥

(प्रदीपः) घञिति व्याख्यास्याम इति । ननु चेनुण आनन्तर्यात्संदेहाभावः । उच्यते—घञोनुवृत्तिसामर्थ्यं दृष्टम्, इनुणश्चानन्तर्यमिति निमित्तसद्भावादस्ति संदेहः ॥

(उद्द्योतः) घञ इति । आनन्तर्यादिनुण्वद्घञ्युपु सूत्रेषूपस्थिततया संस्कारदार्ढ्याद् घञपि झटित्युपस्थितिक इत्यस्ति सन्देहनिमित्तम् ॥ एवं च व्याख्यानादधिकारनिवृत्तिवदधिकारोपि सिद्ध इति सूत्रं व्यर्थमिति भावः ॥

(आक्षेपभाष्यम्)

न तर्हीदानीमयं योगो वक्तव्यः ॥

(समाधानभाष्यम्)

वक्तव्यश्च । किं प्रयोजनम् । स्वरितेनाधिकारगतिर्यथा विज्ञायेत । अधिकं कार्यम् । अधिकः कारः ॥

(उद्द्योतः) भाष्येऽधिकारगतिरित्येक फलमुक्त्वा फलान्तरमाह—[अधिकं कार्यमिति ॥] अधिकः कार इति । अधिकारशब्दोऽधिकव्यापारवाची न्यायप्राप्तादधिकोपि व्यापारो प्राप्त इति भावः ॥

(उदाहरणभाष्यम्)

अधिकारगतिः—"गोस्त्रियोरुपसर्जनस्य" इत्यत्र गोटाङ्ग्रहणं चोदितं तन्न कर्तव्यं भवति । स्त्रीग्रहणं स्वरयिष्यते । स्वरितेनाधिकारगतिर्भविष्यतीति स्त्रिय.मित्येवं प्रकृत्य ये विहितास्तेषां ग्रहणं विज्ञास्यते तत्र स्वरितेनाधिकारगतिर्भवतीति न दोषो भवति ॥ [अधिकारगतिः]॥

(द्वितीयफलोदाहरणभाष्यम्)

अधिकं कार्यम्—अपादानमाचार्यः किं न्याय्यं मन्यते ? । यत्र प्राप्य निवृत्तिः । तेनेहैव स्यात्-ग्रामादागच्छति नगरादागच्छति । सांकाश्यकेभ्यः पाटलिपुत्रका अभिरूपतरा इत्यत्र न स्यात् । स्वरितेनाधिकं कार्यं भवतीत्यत्रापि सिद्धं भवति ॥ तथा—अधिकरणमाचार्यः किं न्याय्यं मन्यते ? यत्र कृत्स्न आधारात्मा व्याप्तो भवति । तेनेहैव स्यात्— तिलेषु तैलम्, दध्नि सर्पिरिति । गङ्गायां गावः कूपे गर्गकुलमित्यत्र न स्यात् । स्वरितेनाधिकं कार्यं भवतीत्यत्रापि सिद्धं भवति ॥ अधिकं कार्यम् ॥

(प्रदीपः) **सांकाश्यकेभ्य इति** । बुद्ध्या समीहितैकत्वाः प्रकर्षाश्रयेण पाटलिपुत्रका विभज्यन्ते इति मुख्यापायाभावादपादानसंज्ञा न स्यात् । **ध्रुवमपाये** इत्यत्र तु स्वरितत्वे प्रतिज्ञाते सति बुद्धिपरिकल्पितापायाश्रयणेनापि भवति ॥ **कृत्स्न आधारात्मेति** । सर्वे अवयवा यत्र व्याप्ता इत्यर्थः ॥ **गङ्गायां गाव इति** । गङ्गाशब्दोऽत्र नद्यामेव वर्तते न तु तत्समीपदेशे । तस्य हि मुख्यमेवाधारत्वमित्यप्रयोजनमेतत्स्यात् । नद्यास्तु तत्सामीप्याद्गौणमाधारत्वमिति यत्नात्संज्ञासिद्धिः ॥

(उद्द्योतः) **बुद्ध्येति** । बुद्धिकृतौ विभागसंयोगौ ग्राह्याविति भावः । अभिरूपत्वप्रकारैकबुद्ध्युपारोह एव संयोगः । अभिरूपत्वप्रकारेण सांकाश्यकैरपि संसृज्यमाना बुद्धिरभिरूपतरत्वलक्षणप्रकर्षाश्रयेण साङ्काश्यकान् जहातीति बुद्धेर्विश्लेष एव तद्विषयस्यापि विश्लेष इति भावः ॥ **नद्यास्तु तत्सामीप्यादिति** । ननु कृत्स्नपदेन व्याप्यवृत्त्याधेयक एव मुख्य आधारो विपरीतस्त्वन्याय्य इति प्रतिपादनेन प्रवाहैकदेशे तरन्तीष्वपि गोषु प्रवाहस्य न मुख्यमाधारत्वमिति किं सामीप्यपर्यन्तधावनेनेति चेन्न । कृत्स्नपदं न तथातात्पर्यकं, कटे आस्ते इत्यादेर्मुख्यत्वानापत्तेः । तस्माद् व्याप्यवृत्त्यव्याप्यवृत्त्युभयसाधारणमेवाधारत्वम् । कृत्स्नत्वं च बह्ववयवाभिप्रायकम् । बह्ववयवसंबद्धाधेयकत्वमेव विवक्षितं, **सर्वे** इत्यपि तदभिप्रायकमेवेत्याशयात् । प्रकृतिः स्वार्थे, सप्तम्येव गौणाधारत्वार्थिकेति भाव इति कैयटानुसारिणः ॥ वस्तुतः कृत्स्नपदसङ्कोचे न मानं, कटे आस्ते इत्यप्यमुख्यमेव गङ्गापदस्य प्रवाहपरत्वे तीरपरत्वे चोक्तरीत्या न मुख्यमाधारत्वम् । गङ्गासर्वावयवानामिव तत्समीपदेशसर्वावयवानामपि व्याप्त्यभावात् । किं चात्रौपश्लेषिकमधिकरणत्वम् । अत एव 'मासेऽतिक्रान्ते यद्दीयते तस्यापि मास औपश्लेषिकमधिकरणम्' इति **तत्र च दीयत** इति सूत्रे भाष्ये उक्तम् । समीपेऽप्यौपश्लेषिकं तत्त्वम् । व्यापकाधारस्यैवाधिकरणता न्याय्येत्यत्र मानं तु प्रकृत्यर्थतावच्छेदकविशिष्ट विभक्त्यर्थान्वयौचित्यं, नहि कटैकदेशे कटत्वमस्ति तस्मादेकदेशगताधारत्वस्य कटे आरोपेण बोध इति गौण एव स आधार इति तत्त्वम् ॥

(तृतीयफलोदाहरणभाष्यम्)

अधिकः कारः—पूर्वविप्रतिषेधाश्च न पठितव्या भवन्ति—*गुणवृद्ध्यौत्वतृज्वद्भावेभ्यो नुम् पूर्वविप्रतिषिद्धम्* नुमचिरतृज्वद्भावेभ्यो नुट्* इति । नुम्नुटौ स्वरयिष्येते । तत्र स्वरितेनाधिकः कारो भवतीति नुम्नुटौ भविष्यतः ॥

(प्रदीपः) **पूर्वेति** । **विप्रतिषेधे परं कार्य**मिति वचनात्पूर्वो बाध्यः स्वरितत्वप्रतिज्ञानेन बाधकः सम्पद्यते । तुल्यजातीयस्य बाधकः, न तु नित्यत्वादियुक्तस्य ॥ ११ ॥

(उद्द्योतः) ननु स्वरितत्वेन प्रबलः पूर्वः परमिव नित्यादीनपि बाधेतेत्यत आह—**तुल्यजातीयस्येति** । यादृशदौर्बल्ये प्रसक्ते प्राबल्याय स्वरितत्वं प्रतिज्ञायते तादृशमेव दौर्बल्यं तेनापनीयत इति भावः ॥

(आक्षेपभाष्यम्)

कथं पुनरधिकः कार इत्यनेन पूर्वविप्रतिषेधाः शक्या न पठितुम् ? ॥

(समाधानभाष्यम्)

लोकतः । तद्यथा—लोकेऽधिकमयं कारं करोतीत्युच्यते योऽयं दुर्बलः सन्बलवद्भिः सह भारं वहति । एवमिहाप्यधिकमयं कारं करोतीत्युच्यते योऽयं पूर्वः सन्परं बाधते ॥

अधिकारगतिरुयर्थो विशेषायाधिकं कार्यम् ।
अथ योऽन्योऽधिकः कारः पूर्वविप्रतिषेधार्थः सः ११
स्वरितेनाधिकारः ॥ ११ ॥

इति श्रीमद्भगवत्पतञ्जलिविरचिते व्याकरणमहाभाष्ये प्रथमस्य तृतीयपादे प्रथममाह्निकम् ॥

इत्युपाध्यायजैयटपुत्रकैयटकृते महाभाष्यप्रदीपे
प्रथमस्य तृतीयेपादे प्रथममाह्निकम् ॥

(उद्द्योतः) उक्तमर्थं गाथया संगृह्णाति—भाष्ये **अधिकारगतिरुयर्थेति** ॥ द्वितीयफलम्—**विशेषायेति** । गौणसंग्रहायेत्यर्थः ॥ तृतीयमाह—**अथ योऽन्य इति** ॥ ११ ॥

इति श्रीशिवभट्टसुतसतीगर्भजनागोजीभट्टकृतभाष्यप्रदीपोद्द्योते प्रथमस्य तृतीये पादे प्रथममाह्निकम् ॥

(आदितस्त्रयोदशम्)

अथ प्रथमाध्यायस्य तृतीये पादे द्वितीयमाह्निकम् ।

(आदितश्चतुर्दशम्)

(अथात्मनेपदनियमप्रकरणम् ॥)

(१३० नियमसूत्रम् ॥ १।३। २ आ० १ सू०)

१५९ अनुदात्तङित आत्मनेपदम् ॥ १।३।१२ ॥

(अनिष्टवारणाधिकरणम्)

(८९१ आक्षेपवार्तिकम् ॥ १ ॥)

[॥ * ॥ विकरणेभ्यः प्रतिषेधः ॥ * ॥]

(भाष्यम्)

विकरणेभ्यः प्रतिषेधो वक्तव्यः । चिनुतः सुनुतः लुनीतः । ङित इत्यात्मनेपदं प्राप्नोति ॥

(प्रदीपः) **अनुदात्त** ॥ १२ ॥ **विकरणेभ्य इति** ।

लादेशेषु कृतेषु नियमात्पूर्वं नित्यत्वाद्विकरणास्तेषां **सार्वधातुकमपिद्** इति ङित्त्वातिदेशादात्मनेपदनियमोनेन प्राप्नोतीति ॥

(उद्द्योतः) अनुदात्तङि ॥ १२ ॥ ननु लादेशविधायकस्यैतैरेकवाक्यत्वान्नियमोत्तरमेव विकरणोऽत आह—**लादेशेष्विति**। एकवाक्यतापक्षस्तु भाविसंज्ञाश्रयणक्लेशदुष्ट इति भावः ॥ पक्षप्राप्तपरस्मैपदनिवर्त्तकतया चास्य नियमत्वम् । स्पष्टाचेयं रीतिर्युष्मद्युपपद इति सूत्रे कैयटे ॥

(आक्षेपबाधकभाष्यम्)

नैष दोषः । नैवं विज्ञायते–'ङकार इद्यस्य सोयं ङिद् ङितः' इति ॥ कथं तर्हि ? । ङकार इद् ङित् ङित इति ॥

(प्रदीपः) **ङकार इदिति** । अन्यपदार्थापेक्षणाद्बहिरङ्गो बहुव्रीहिः । तत्पुरुषस्तु वर्तिपदार्थप्रधानत्वादन्तरङ्ग इति स एवाश्रीयते । केवलाच्च ङकारादित आत्मनेपदासम्भवात्सामर्थ्यात्तदन्तविधेर्वाऽत्र ङिदन्त आश्रीयते । तेन ङिदन्तादात्मनेपदमित्यर्थः ॥

(उद्द्योतः) केवलाच्चेति । तस्य लोपावश्यंभावादिति भावः ॥ **सामर्थ्यादिति** । तेन च येन विधिरितिशास्त्रप्रवृत्त्यभावेपि तदन्तग्रहणमित्यर्थः ॥ **तदन्तविधेर्वेति** । शब्दं विशेष्यीकृत्य तत्सामर्थ्यात् शास्त्रप्राप्तेर्वेत्यर्थः ॥ **तेन ङिदन्तादिति** । इत्संज्ञकङकारान्तादित्यर्थः । अतिदेशे तु ङिदितिबहुव्रीहिरेव क्ङिति चेत्याद्यनुरोधादिति भावः ॥

(आक्षेपबाधकान्तरभाष्यम्)

अथ वोपदेश इति वर्तते ॥

(प्रदीपः) **अथवेति** । तेनोपदेशे यो ङित्तस्मादात्मनेपदम्, न त्वातिदेशिकङित्त्वेभ्यः ॥

(उद्द्योतः) **तेनेति** । अत्र पक्षे ङिदितिबहुव्रीहिरेवेति भावः॥ षष्ठीतत्पुरुषोपि क्ङिति चेत्याद्येकरूप्याय शास्त्रे आश्रीयत इति बोध्यम् ॥

(आक्षेपबाधकान्तरभाष्यम्)

अथवोक्तमेतत् *सिद्धं तु पूर्वस्य कार्यातिदेशात्* इति ॥

(उद्द्योतः) भाष्ये—सिद्धं तु पूर्वस्येति । पूर्वपदस्य परनिमित्तत्वात्पचेते इत्यादावातो ङित इति भवत्येव ॥

(आक्षेपसाधकभाष्यम्)

सर्वथा चङ्क्रम्यां प्राप्नोति ॥

(समाधानभाष्यम्)

एवं तर्हि 'धातोः' इति प्रकृतं वर्तते ॥ क प्रकृतम् ? । "भूवादयो धातवः" इति ॥

(प्रदीपः) **एवं तर्हीति** । अत्रापि पक्षे उत्कुटिषतीत्यतिप्रसङ्गनिवारणार्थं सिद्धं तु पूर्वस्य कार्यातिदेशादित्यप्याश्रयणीयम् ॥

(उद्द्योतः) **अत्रापीति** । कुटेः सनो गाङ्कुटादिभ्य इति ङित्वात्सनन्तस्य ङिदन्तधातुत्वादिति भावः ॥ शेत इत्यादौ तु व्यपदेशिवद्भावात् सिद्धिरिति बोध्यम् ॥ **इत्यपीति** । उपदेशपदानुवृत्तिर्वा कर्मधारयो वेत्यपि बोध्यम् ॥

(आक्षेपभाष्यम्)

तद्वै प्रथमानिर्दिष्टम्, पञ्चमीनिर्दिष्टेन चेहार्थः ॥

(समाधानभाष्यम्)

अर्थाद्विभक्तिविपरिणामो भविष्यति । तद्यथा—'उच्चानि देवदत्तस्य गृहाणि, आमन्त्रयस्व' 'एनं देवदत्तम्' इति गम्यते । 'देवदत्तस्य गावोऽश्वा हिरण्यं च' 'आढ्यो वैधेयः' 'देवदत्त' इति गम्यते । पुरस्तात्षष्ठीनिर्दिष्टं सदर्थात्प्रथमानिर्दिष्टं द्वितीयानिर्दिष्टं च भवति । एवमिहापि पुरस्तात्प्रथमानिर्दिष्टं सदर्थात्पञ्चमीनिर्दिष्टं भविष्यति ॥

(प्रकरणप्रयोजनाक्षेपभाष्यम्)

किमर्थं पुनरिदमुच्यते ? ।

(प्रदीपः) **किमर्थमिति** । किं विहितानां लादेशानामनेन नियमः क्रियते । अथ वाक्यैकवाक्यतया विधिरिति प्रश्नः ॥

(उद्द्योतः) [वाक्यैकवाक्यतयेति । आपाततोऽवान्तरवाक्यार्थबोधोत्तरं वाक्यैकवाक्यतया महावाक्यार्थबोध इत्यर्थः ॥] इति प्रश्न इति ॥ प्रयोजनस्य स्पष्टत्वान्न तदाक्षेपपरमिति भावः । चङाद्यन्ते प्रकारान्तरेणातिव्याप्तिं परिहर्तुमयमुपक्षेप इति बोध्यम् ॥

(८१२ समाधानवार्तिकम् ॥ २ ॥)

॥ * ॥ आत्मनेपदवचनं नियमार्थम् ॥ * ॥

(भाष्यम्) **नियमार्थोयमारम्भः ॥**

(प्रदीपः) **नियमार्थ इति** । एकवाक्यतायां भाविनी संज्ञाश्रयणीयेति वाक्यभेद एवाश्रीयते । तेन नियमोयं सम्पद्यते ॥

(उद्द्योतः) **एकवाक्यतायामिति** । लादेशाश्रयसंज्ञामूलविधानेऽन्योन्याश्रयापत्तेरनुदात्तङित इत्यादौ भाविसंज्ञाश्रयणीया स्यात् । अनुदात्तङितो लस्य स्थाने ते तिबादयो भवन्ति येषां जातानामात्मनेपदसंज्ञा भविष्यतीत्यर्थादिति भावः ॥ **वाक्यभेद एवेति** । वाक्यभेदेप्येतन्मुखनिरीक्षणेनैव लक्ष्यसंस्कारकं तिबादिसूत्रं न ततः स्वतन्त्रमिति बोध्यम् । नियमार्थत्वपक्षेऽन्येषां प्राप्तानामेतत्सामर्थ्यान्निवृत्तिः । एकवाक्यतापक्षे तु तेषामप्राप्तिरेवेति विशेषः ॥

(आक्षेपभाष्यम्)

किमुच्यते नियमार्थोयमिति न पुनर्विध्यर्थोपि स्यात्?॥

(उद्द्योतः) भाष्ये तिप्तसित्यादिना सिद्धत्वान्नियमार्थत्वमित्यजानानः शङ्कते—किमुच्यते इति॥

(८९३ समाधानसाधकवार्तिकम्॥ ३॥)

॥ * ॥ लविधानाद्विहितम्॥ * ॥

(भाष्यम्) लविधानाद्ध्यात्मनेपदं परस्मैपदं च विहितम्॥

(उद्द्योतः) लविधानादिति। लपदं तदादेशलक्षकमिति बोध्यम्॥

(भाष्यम्) अस्ति प्रयोजनमेतत्॥ किं तर्हीति॥

(८९४ आक्षेपवार्तिकम्॥ ४॥)

[॥ * ॥ विकरणव्यवहितत्वात्तु नियमाप्राप्तिः॥ * ॥]

(भाष्यम्) विकरणैस्तु व्यवहितत्वान्नियमो न प्राप्नोति॥ इदमिह संप्रधार्यं विकरणाः क्रियन्तां नियम इति। किमत्र कर्तव्यम्?। परत्वाद्विकरणाः॥ नित्याः खल्वपि विकरणाः, कृतेपि नियमे प्राप्नुवन्त्यकृतेपि प्राप्नुवन्ति। नित्यत्वाच्च परत्वाच्च विकरणेषु कृतेषु विकरणैर्व्यवहितत्वान्नियमो न प्राप्नोति॥

(प्रदीपः) परत्वादिति। विकरणानामवकाशः अलादेशाश्वानशादयः। नियमस्यावकाशः लिङ्लिटावार्धधातुकसंज्ञौ। स्पर्द्धत इत्यादावुभयप्रसङ्गे परत्वाद्विकरणस्तेन व्यवधानान्नियमाप्रसङ्गः॥

(उद्द्योतः) अन्यतरस्यानवकाशत्वे विप्रतिषेधायोगाद् द्वयोः सावकाशतां दर्शयति—विकरणानामिति। यद्यपि नित्यानित्ययोरयुक्तः स तथापि पूर्वं नित्यत्वास्मृतेर्न दोष इति बोध्यम्॥ परत्वादिति। यद्यपि प्राप्तस्यैव बाध इति सार्वधातुकपरत्वं दुरुपपादं तथापि शास्त्रतः प्राप्तिमात्रेण बौद्धं परत्वमादाय तत्प्रवृत्तिरिति भावः॥

(आक्षेपबाधकभाष्यम्)

नैष दोषः। अनवकाशो नियमः॥

(प्रदीपः) अनवकाश इति। सर्वत्र विकरणानां व्यवधायकत्वादिति भावः॥

(उद्द्योतः) इति भाव इति। इत्यभिमान इत्यर्थः॥

(आक्षेपसाधकभाष्यम्)

सावकाशः॥ कोऽवकाशः?। य एते लुग्विकरणाश्च श्लुविकरणाश्च, लिङ्लिटौ च॥

(परिभाषात्वाङ्गीकारभाष्यम्)

यदि पुनरियं

(८९५ पक्षान्तरवार्तिकम्॥ ५॥)

॥ * ॥ परिभाषा॥ * ॥

(भाष्यम्) विज्ञायेत। किं कृतं भवति?। 'कार्यकालं संज्ञापरिभाषम्' यत्र कार्यं तत्र द्रष्टव्यम्'। लस्य तिबादयो भवन्तीत्युपस्थितमिदं भवति "अनुदात्तङित आत्मनेपदम्" "शेषात्कर्तरि परस्मैपदम्" इति॥

(प्रदीपः) यदि पुनरिति। आत्मनेपदपरस्मैपदाभ्यां लिङ्गाभ्यामिदं प्रकरणं लादेशविधावुपतिष्ठते। तत्र महावाक्येन विहितेषु लादेशेषु विकरणा इति दोषाभावः॥ स्यादिषु कथम्। ते हि लावस्थायामेव विधीयन्ते इति तैर्व्यवधानान्नियमो न प्राप्नोति॥ उच्यते—लमात्रापेक्षत्वादन्तरङ्गत्वाल्लादेशेषु कृतेषु लकारविशेषापेक्षया बहिरङ्गाः स्यादयो भविष्यन्ति येन नाप्राप्तिन्यायेन शबादीन्बाधित्वा। शबादिविधावनुवर्तनाद्वा॥

(उद्द्योतः) परिभाषाया लिङ्गवत्त्वनियमात्तद्दर्शयति—आत्मनेपदेति। यथोद्देशे वाक्यभेदस्यैव सत्त्वात्कार्यकालाश्रयणम्। उपस्थितस्य च वाक्यैकवाक्यतयान्वयः। स चेत्थम्—लस्य स्थाने तिबादयो भवन्ति। ते चानुदात्तङितः परस्य लस्य स्थाने तादृशा भवन्ति येषां जातानामात्मनेपदसंज्ञा भवतीति॥ न चावान्तरवाक्यार्थबोधोत्तरं तेषां लस्थानिकत्वज्ञानादात्मनेपदादिसंज्ञोत्तरमेवैकवाक्यतास्तु किं भाविसंज्ञाश्रयणेनेति वाच्यम्। अस्य तत्रोपस्थितौ तावत्पर्यन्तं तेनासंबद्धतयाऽवस्थाने मानाभावात्। अन्तरङ्गतयाऽनेन संबन्धानुभवोत्तरमेव तिबादिभिः संज्ञानुभवात्॥ तत्र महावाक्येनेति। अत एव भाष्येपि लस्य तिबादयो भवन्तीत्युपस्थितमिदं भवति—अनुदात्तेत्याद्युक्तम्॥ अत्रेदं बोध्यम्—कार्यकालपक्षेपीदमेव सूत्रं स्वाकाङ्क्षया तेनैकवाक्यतामनुभवति। परिभाषेत्यस्य परिभाषावदित्यर्थः। यथा परिभाषा कार्याकाङ्क्षावशात्तेनैकवाक्यतापन्ना तथेदमपि स्वाकाङ्क्षावशात्। आकाङ्क्षोत्थापके च लिङ्गव्यवहारः। प्रकृते चास्य तदाकाङ्क्षोत्थापकावात्मनेपदत्वादिना बोधकावेतौ शब्दाविति तत्र लिङ्गत्वव्यवहारः॥ एतेन सर्वत्र परिभाषालिङ्गं विधेः परिभाषाकाङ्क्षोत्थापकं विधौ दृष्टं, न चात्र तथा, विधिसूत्रे आत्मनेपदत्वादिनानुपस्थितेरितीदमयुक्तमित्यपास्तमिति॥ एवं च धातोरित्यनुवृत्त्यर्थं मण्डूकप्लुतिविभक्तिविपरिणामश्च नाश्रयणीयाविति बोध्यम्॥ लकारविशेषेति। अपरनिमित्तकत्वेन लादेशानामन्तरङ्गत्वं वक्तुं योग्यम्, ईदृशान्तरङ्गत्वस्य भाष्ये क्वाप्यनाश्रयणादिति केचित्॥ नन्वेवं परत्वाच्छबादयः स्युरत आह—येन नेति॥ ननु भावकर्मणोर्व्यभिचारिताश्र्यात्कथमयं न्यायः। न च तत्रापि यका बाधः। एवं तर्हि पुरस्तादपवादा इतिन्यायेन यक एव बाधः स्यान्न शबादेः। किं च श्यनादिभिर्येन नाप्राप्तिन्यायाभावात्तद्विषये सावकाशाः। किं च लुग्विकरणादिषु शपो निवृत्तौ स्यादयः सावकाशा इत्यत आह—शबादीति। आदेशेषु कृतेषु लावस्थाभावात्स्याद्यप्राप्तिश्चिन्त्यमिदम्। लावस्थायां स्यादय इत्यनाश्रित्य मिति वक्तुं युक्तम्। तत्पक्षे तु धातोरितिवदनुदात्तङित इत्यपि विहितविशेषणमिति बोध्यम्॥

(अन्योन्याश्रयाक्षेपभाष्यम्)

एवमपीतरेतराश्रयं भवति ॥ का इतरेतराश्रयता ? ॥ अभिनिर्वृत्तानां लस्य स्थाने तिबादीनामात्मनेपदपरस्मैपदसंज्ञया भवितव्यम् । संज्ञया च तिबादयो भाव्यन्ते । तदितरेतराश्रयं भवति, इतरेतराश्रयाणि च कार्याणि न प्रकल्पन्ते ॥

(प्रदीपः) एवमपीति । एकवाक्यतापक्षे विहिता लादेशा न सन्ति येन तेषां सतामात्मनेपदपरस्मैपदसंज्ञे स्याताम् । ततश्चैतत्परिभाषोपस्थाने सति संज्ञाश्रयं लादेशविधानम्, लादेशविधानाश्रया च संज्ञेति भावः ।

(उद्द्योतः) एकवाक्यतेति । परिभाषापक्षे इति भावः ॥

(अन्योन्याश्रयपरिहारभाष्यम्)

परस्मैपदेषु तावन्नेतरेतराश्रयं भवति । परस्मैपदानुक्रमणं न करिष्यते ॥

(प्रदीपः) परस्मैपदानुक्रमणमिति । नन्वसति परस्मैपदानुक्रमणे परस्मैपदमनुदात्तङिद्भ्यः प्राप्नोति । नैष दोषः । आत्मनेपदसम्बन्धावगमेन तेषां परस्मैपदसम्बन्धस्य बाधनाच्छेषादेव परस्मैपदमवस्थास्यते ॥

(उद्द्योतः) नन्वसतीति । प्रत्ययनियमाश्रयणेऽनुदात्तादिभ्य एवात्मनेपदं धातुमात्रात्परस्मैपदमिति पर्यवसानात् कादिविषये ङिविवेति भावः ॥ बाधनादिति । प्रकृतिनियमाश्रयणेनेत्यर्थः । कङ्किपोस्तु वासरूपविधिना समावेश इति भावः ॥

(आक्षेपभाष्यम्)

अवश्यं कर्तव्यम् "अनुपराभ्यां कृञः" इत्येवमर्थम् ॥

(प्रदीपः) अवश्यमिति । आत्मनेपदबाधनार्थमित्यर्थः ॥

(आक्षेपबाधकभाष्यम्)

ननु चैतदप्यात्मनेपदानुक्रमण एव करिष्यते "स्वरितञितः कर्त्रभिप्राये क्रियाफले" आत्मनेपदं भवति, "कर्तर्यनुपराभ्यां कृञो न" इति ॥

(अन्योन्याश्रयपरिहारभाष्यम्)

आत्मनेपदेषु चापि नेतरेतराश्रयं भवति ॥ कथम् ? ॥ भाविनी संज्ञा विज्ञास्यते सूत्रशाटकवत् । तद्यथा—कश्चित्कंचित्तन्तुवायमाह—'अस्य सूत्रस्य शाटकं वय' इति । स पश्यति—यदि शाटको न वातव्यः, अथ वातव्यो न शाटकः, शाटको वातव्यश्चेति विप्रतिषिद्धम्, भाविनी खल्वस्य संज्ञाभिप्रेता—स मन्ये वातव्यो यस्मिन्नुते शाटक इत्येतद्भवति—इति । एवमिहापि—स लस्य स्थाने कर्तव्यः, यस्याभिनिर्वृत्तस्यात्मनेपदमित्येषा संज्ञा भविष्यति ॥

(नियमपक्षाभ्युपगमभाष्यम्)

अथ वा पुनरस्तु नियमः ॥

(उद्द्योतः) भाष्ये—अथ वा पुनरिति । वाक्यभेदेनेत्यर्थः ॥

(आक्षेपस्मारणभाष्यम्)

ननु चोक्तं विकरणैर्व्यवहितत्वान्नियमो न प्राप्नोति ॥

(आक्षेपनिरसनभाष्यम्)

नैष दोषः । आचार्यप्रवृत्तिर्ज्ञापयति—'विकरणेभ्यो नियमो बलीयान्' इति । यदयं विकरणविधावात्मनेपदपरस्मैपदान्याश्रयति "पुषादिद्युताद्यॢदितः परस्मैपदेषु" "आत्मनेपदेष्वन्यतरस्याम्" इति ॥

(प्रदीपः) यदयमिति । कृतनियमानामसङ्करेण स्थितानां हि निमित्तभावोपपत्तिः ॥

(उद्द्योतः) कृतेति । भिन्नवाक्यतायां तिबादिसूत्रेणोपात्तरूपतया प्रसक्तस्यैव प्रतिपन्नस्य न निमित्तत्वमिति भावः ॥

(नियमपक्षसाधकज्ञापकनिरसनभाष्यम्)

नैतदस्ति ज्ञापकम् । अभिनिर्वृत्तानि हि लस्य स्थाने आत्मनेपदानि परस्मैपदानि च ॥

(प्रदीपः) अभिनिर्वृत्तानीति । प्रागपि नियमात्तेषां सम्भवमात्रेण निमित्तत्वाविरोधात् ॥

(उद्द्योतः) भाष्ये अभिनिर्वृत्तानीत्यस्य प्राप्तानीत्यर्थः ॥

(ज्ञापकान्तरभाष्यम्)

यत्तर्हि—"अनुपसर्गाद्वा" इति विभाषां शास्ति ॥

(प्रदीपः) यत्तर्हीति । एतत्तु लिङ्लिङर्थं स्यात् । चक्रमे चक्राम क्रम्यात् क्रंसीष्टेति । तस्माज्ज्ञापकदिक् प्रदर्शिता भाष्यकृता । ज्ञापकं तु वृद्भ्यः स्यसनोरित्यत्र से विकल्पविधानम् ॥

(उद्द्योतः) वृद्भ्य इति । अन्यथा विकरणव्यवधाने नियमाप्रवृत्तावुभयोरपि पदयोः सामान्यशास्त्रेण सिद्धतया तद्विधानं विफलं संदेतदर्थज्ञापकम् ॥ से इति त्वेतत्पक्षे विषयसप्तमीति भावः । विकरणव्यवधानेपि नियमप्रवृत्तिर्ज्ञाप्यत इति शब्दः शित इति सूत्रे भाष्ये ध्वनितमिति वक्ष्यते ॥ अत एव ज्ञावस्थायां स्यादय इति पक्षेपि न दोषः ॥ केचित्तु भाष्यप्रामाण्यादनुपसर्गाद्वेत्यस्याशीर्लिङ्लिटोरप्रवृत्तिरित्याहुः ॥

(अथ प्रत्ययनियमप्रकृत्यर्थनियमनिर्णयप्रकरणम्)

(आक्षेपभाष्यम्)

किं पुनरयं प्रत्ययनियमः—अनुदात्तङित एवात्मनेपदं भवति, भावकर्मणोरेवात्मनेपदं भवतीति। आहोस्वित्प्रकृत्यर्थनियमः—अनुदात्तङित आत्मनेपदमेव, भावकर्मणोरात्मनेपदमेवेति ॥

(प्रदीपः) **किं पुनररिति** । उभयनियमस्तावन्न संभवति । अनेकस्मिन्नर्थे वाक्यस्यैकस्य तात्पर्यायोगात् । तस्मादन्यतरनियमसंभवात्प्रश्नः ॥ ननु प्राधान्यात्प्रत्ययानां नियमो युक्तः ॥ एवं तर्हि प्रधानोपरोधो मा भूदिति प्रकृत्यर्थनियमोपि संभवति ॥ **भावकर्मणोरेवेति** । ननु पूर्वेण नियमाद्भावकर्मणोरिति सूत्रं विध्यर्थं न्याय्यं न तु नियमार्थम् ॥ नैष दोषः । समस्तमात्मनेपदप्रकरणमेकं वाक्यमिति तदपेक्षयैतदुक्तम् ॥

(उद्द्योतः) उभयनियमपक्षोपि सम्भवन् किमिति नोक्त इत्यत आह—उभयेति ॥ एकस्येति । सकृदुच्चरित इतिन्यायादिति भावः ॥ नन्विति । 'प्रधाने कार्यसंप्रत्ययाद्' इति । न्यायादित्यर्थः ॥ एवं तर्हीति । न्यायद्वयस्यापि सत्त्वात्संदेह इति प्रश्नः ॥ प्रकृत्यर्थेति । द्वन्द्वः ॥ नन्विति । अनुदात्तङित एवेत्यत्रैवकारस्यान्ययोगव्यवच्छेदार्थकत्वात्प्रकृत्यन्तरात्कुत्राप्यर्थे तदप्राप्तौ विध्यर्थत्वमेव न्याय्यमिति भावः ॥ **नैष इति** । सलेकपोतन्यायेन संपूर्णप्रकरणं युगपदेव प्रवृत्तमिति भावः ॥

(भाष्यम्) **कश्चात्र विशेषः ? ॥**

(८९६ प्रत्ययनियमदूषणवार्तिकम् ॥ ६ ॥)

॥ * ॥ तत्र प्रत्ययनियमे शेषवचनं परस्मैपदस्यानिवृत्तत्वात् ॥ * ॥

(भाष्यम्) **तत्र प्रत्ययनियमे शेषग्रहणं कर्तव्यं परस्मैपदनियमार्थम्—"शेषात्कर्तरि परस्मैपदम्" इति । किं कारणम् ? । परस्मैपदस्यानिवृत्तत्वात् । प्रत्यया नियताः, प्रकृत्यर्थावनियतौ । तत्र परस्मैपदमपि प्राप्नोति ॥ तत्र शेषग्रहणं कर्तव्यं परस्मैपदनियमार्थम् 'शेषादेव परस्मैपदं भवति, नान्यत' इति ॥**

(उद्द्योतः) भाष्ये—तत्र परस्मैपदमपीति । अनुदात्तङिभ्य इत्यर्थः ॥

(८९७ दूषणान्तरवार्तिकम् ॥ ७ ॥)

॥ * ॥ क्यष आत्मनेपदवचनं तस्यान्यत्र नियमात् ॥ * ॥

(भाष्यम्) **क्यष आत्मनेपदं वक्तव्यम् । लोहितायति लोहितायते ॥ किं पुनः कारणं न सिध्यति ? । तस्यान्यत्र नियमात् । तद्ध्यन्यत्र नियम्यते ॥**

(प्रदीपः) **क्यष इति** । वा क्यष इति परस्मैपदे विकल्पिते आत्मनेपदस्यानुदात्तङिदादिषु नियतत्वादप्राप्तत्वाल्लकारस्य श्रवणप्रसङ्गः ॥

(उद्द्योतः) प्रत्ययनियमे दोषान्तरमाह—भाष्ये क्यष आत्मनेपदं वक्तव्यमिति । वा क्यष इत्यादिचतुःसूत्री शेषादित्यतः प्राक्कार्येति भावः ॥ लकारस्येति । वाग्रहणादिति भावः ॥ लान्तस्यापि कृदन्तत्वात्प्रातिपदिकत्वे सुपि पदत्वादपदं न प्रयुञ्जीतेत्यस्य न विषय इति बोध्यम् ॥

(दूषणोद्धारकभाष्यम्)

उच्यते च, न च प्राप्नोति । तद्वचनाद्भविष्यति ॥

(प्रदीपः) **उच्यते चेति** । लकारे तिबादिभिर्निवर्तिते नियमः प्रवर्तते तत्र परस्मैपदस्य सिद्धत्वाद्वावचनेन तस्मिन्विकल्प्यमाने वचनमनर्थकं स्यात् । केवलायाः प्रकृतेरप्रयोगार्हत्वाच्छब्दमन्तरेणार्थस्य प्रतिपादयितुमशक्यत्वात् प्रयोगविकल्पायोगात् । तस्मादात्मनेपदमेव विकल्पेन विधीयते ॥

(उद्द्योतः) भाष्ये—उच्यते चेत्यस्य विकल्पपक्षात्मनेपदमिति शेषः ॥ न च प्राप्नोतीत्यस्यात्मनेपदमिति शेषः ॥ तद् आत्मनेपदम् ॥ वचनात् वा क्यष इति वचनादित्यर्थः ॥ ननु वावचनेन लकारस्यैव पाक्षिकत्वमुच्यते न त्वात्मनेपदस्येत्यत आह—लकार इति । भिन्नवाक्यतापक्षे सामान्यसूत्रप्रवृत्त्यनन्तरभावित्वादेतत्प्रकरणेन पूर्वनिवृत्तलस्य प्रत्यायनमशक्यं तिङ्विषयत्वाच्च तदन्तस्य कृत्त्वमप्यशक्यम् ॥ ननु केवलप्रकृतिप्रयोगस्तर्हि तेनोच्यतेऽत आह—केवलाया इति ॥ नन्वेवमपि प्रयोगविकल्पोऽस्त्वत आह—शब्दमिति । साधुप्रयोगनिर्वाहप्रवृत्तशास्त्रेण क्यषन्तप्रयोगाभावस्य बोधयितुमयुक्तत्वादिति भावः ॥ एवं च *क्यष आत्मनेपदवचनम्* इति द्वितीयदोष उद्धृतः । *शेषग्रहणं कर्तव्यम्* इति दोषस्त्वस्त्येव ॥ नन्वापाततस्तिबादिसूत्रेण प्रसक्तमुभयपदिम्वं यथा पाश्चात्यैर्नियमैरपोद्यते, एवं प्रथमं नित्यवत् श्रुतं लकारनिवर्तनं पाक्षिकमिति कल्पयितुं युक्तम् । किं च दधि इत्यादिवत्केवलप्रकृतिप्रयोगोपि वक्तुं शक्य इति चेन्न । तिबादिसूत्रेण युगपदुभयप्रत्ययपरत्वासम्भवादर्थाक्षिप्तस्तयोर्विकल्पः । स एव तत्तन्नियमैरप्राप्तः पुनर्वा क्यष इत्यनेन प्रतिप्रसूयत इति कल्पनाया एव युक्तत्वान्न दोषः । एकवाक्यतापक्षेपि यदीदं प्रकरणं न स्यात्तदेव विकल्प इति सम्भावितस्य तस्यैव प्रतिप्रसव इति न दोषः ॥ ननु प्रत्ययनियमपक्षे शेषादिति कृतेपि दोषः । कर्तरीत्यस्य सत्त्वेन कर्तरि शेषादेवेत्यर्थेऽर्थान्तरे परस्मैपदस्य सर्वत आपत्तेरिति चेत्सत्यम् । विनिगमनाविरहेण कर्त्तर्येव, शेषादेवेति नियमद्वयाङ्गीकारेणादोषात् ॥ नन्वेवमपि भावकर्मणोरेवेति धातुमात्रविषय-

नियमेनानुदात्तङ्घिद्भ्योपि कर्त्तरि तद्धाननापत्तिः । न चानुदात्त-ङित इत्यस्य वैयर्थ्यम्, शेषाद्भावकर्मणोस्तत्प्राप्त्यर्थं चारितार्थ्यादिति चेत् ॥ न, योगविभागसामर्थ्येनास्य कर्त्रर्थत्वाददोषः ॥

(प्रकृत्यर्थनियमाङ्गीकारभाष्यम्)

अस्तु तर्हि प्रकृत्यर्थनियमः ॥

(उद्द्योतः) भाष्ये—अस्तु तर्हीति । शेषादिति कर्त्तव्यता-रूपाद्दोषादित्यादिः ॥

(८९८ प्रकृत्यर्थनियमदूषणवार्तिकम् ॥ ८ ॥)

॥ * ॥ प्रकृत्यर्थनियमेऽन्याभावः ॥ * ॥

(भाष्यम्) प्रकृत्यर्थनियमे अन्येषां प्रत्ययानाम-भावः । अनुदात्तङ्घितस्तृजादयो न प्राप्नुवन्ति ॥

(दूषणबाधकभाष्यम्)

नैष दोषः । अनवकाशास्तृजादयः । उच्यन्ते च, ते वचनाद्भविष्यन्ति ॥

(दूषणसाधकभाष्यम्)

सावकाशास्तृजादयः ॥ कोऽवकाशः ? । परस्मै-पदिनोऽवकाशः ॥

(उद्द्योतः) परस्मैपदिनोवकाश इति भाष्यादवकाशशब्दो नित्यैकवचनान्तः, करणादीन्यवकाश इति कैयटाल्लिङ्गपुल्लिङ्गः, सिङ्क्स्तान्यवकाश इति सरूपसूत्रस्थभाष्याच्चेति बोध्यम् ॥

(दूषणबाधकभाष्यम्)

तत्रापि नियमान्न प्राप्नुवन्ति ॥

(उद्द्योतः) तत्रापि नियमान्नेति । तेषु परस्मैपदमेवेति नियमादित्यर्थः । एवं चानवकाशत्वाद्वचनसामर्थ्याद्भविष्यन्तीति प्रकृत्यर्थनियमे न दोष इति भावः ॥

(दूषणसाधकभाष्यम्)

तव्यदादयस्तर्हि भावकर्मणोर्नियमान्न प्राप्नु-वन्ति ॥

(दूषणबाधकभाष्यम्)

तव्यदादयोप्यनवकाशाः । ते वचनाद्भवि-ष्यन्ति ॥

(प्रदीपः) तव्यदादयोपीति । यद्यपि स्नानीयं चूर्ण-मित्यादौ करणादीन्यवकाशः, तथापि **तयोरेवेति** चोदनया भावकर्मणोर्यद्विधानं तदनवकाशम् ॥

(उद्द्योतः) तथापीति । बहुलग्रहणोन्नीतविधेश्चारितार्थ्येपि **तयोरेवेति** विधेरचारितार्थ्यादिति भावः ॥

(दूषणसाधकभाष्यम्)

चिण्तर्हि भावकर्मणोर्नियमान्न प्राप्नोति ॥

(प्रदीपः) **चिण् तर्हीति** । ननु भावकर्मणी सार्वधातु-कस्यार्थौ न चिणस्तत्कथमप्राप्तिश्चोद्यते । सहाभिधानपक्षे चि-णोपि भावकर्मणी अर्थावित्यदोषः ॥

(उद्द्योतः) सहाभिधानेति । यद्यप्यनिर्दिष्टार्थानां स्वार्थि-कत्वेन प्रकृत्य[र्था]र्थकतैव न्याय्या, तथापि व्याकरणान्तरेऽतिप्रत्ययादि-कल्पनादर्शनादयं पक्ष आश्रितः सहाभिधानेपि द्वावितिवदर्थवत्ता प्र-त्येकमेव पर्याप्तेति बोध्यम् । सहाभिधानं द्योतकत्वेनोभयोरपि द्योत-कत्वादिति तत्त्वम् ॥

(दूषणबाधकभाष्यम्)

चिण्वचनाद्भविष्यति ॥

(दूषणसाधकभाष्यम्)

घञ् तर्हि भावकर्मणोर्नियमान्न प्राप्नोति ॥

(प्रदीपः) **घञ् तर्हीति** । अकर्तरि विधीयमानोपादा-नादिषु घञ् सावकाशः ॥

(उद्द्योतः) अकर्त्तरीति । भावे घञ् त्वनवकाशत्वात्सिद्ध इति भावः ॥

(दूषणबाधकभाष्यम्)

तत्रापि प्रकृतं कर्मग्रहणमनुवर्तते ॥ क प्रकृ-तम् ? । "अण्कर्मणि च" इति ॥

(दूषणसाधकभाष्यम्)

तद्वै तत्रोपपदविशेषणम् । अभिधेयविशेषणेन चेहार्थः । न चान्यार्थं प्रकृतमन्यार्थं भवति । न खल्वप्यन्यत्प्रकृतमनुवर्तनादन्यद्भवति नहि गोधा सर्पन्ती सर्पणादहिर्भवति ॥

(प्रदीपः) **उपपदविशेषणमिति** । सप्तमीस्थस्य सा-मान्यस्य कर्मणीत्यनेन विशेषस्य प्रतिपादनादुपपदविशेषणमु-च्यते । एवमभिधेयविशेषणेनेति व्याख्येयम् ॥

(उद्द्योतः) ननूपपद इति विशेष्याभावात्कथं कर्मणीत्यस्य तद्विशेषणत्वमत आह—**सप्तमीति** । विशेषोपस्थापकत्वमत्र विशेषणपदेन विवक्षितमिति भावः ॥ स्वघटितसूत्रे भावलक्षण-सप्तम्यन्तमनुवृत्तिमात्रेण कथं विषयसप्तम्यन्तं स्यादिति शङ्का-भाष्यार्थः ॥ शब्दाधिकार एवाश्रित इति परिहारः ॥

(दूषणपरिहारभाष्यम्)

यत्तावदुच्यते—नान्यार्थं प्रकृतमन्यार्थं भव-तीति ॥ अन्यार्थमपि प्रकृतमन्यार्थं भवति । त-द्यथा । शाल्यर्थं कुल्याः प्रणीयन्ते ताभ्यश्च पा-नीयं पीयते उपस्पृश्यते शालयश्च भाव्यन्ते ॥ यदप्युच्यते—न खल्वप्यन्यत्प्रकृतमनुवर्तनादन्य-द्भवति नहि गोधा सर्पन्ती सर्पणादहिर्भवतीति ॥ भवेद्द्रव्येष्वेतदेवं स्यात् । शब्दस्तु खलु येनये-नाभिसंबध्यते तस्यतस्य विशेषको भवति ॥

(८९९ दूषणान्तरवार्तिकम् ॥ ९ ॥)

॥ * ॥ शेषवचनं च ॥ * ॥

(भाष्यम्) शेषवचनं च कर्तव्यम् "शेषात्कर्तरि परस्मैपदम्" इति ॥ किं प्रयोजनम् ? । शेषनियमार्थम् । प्रकृत्यर्थौ नियतौ, प्रत्यया अनियताः, ते शेषेपि प्राप्नुवन्ति । तत्र शेषग्रहणं कर्तव्यम्—शेषात्कर्तरि परस्मैपदमेव नान्यदिति ॥

(उद्द्योतः) भाष्ये प्रत्ययनियमवादी मत्पक्षे त्वयोद्भावितं गौरवमत्रापि समानमित्याह—शेषवचनं चेति । अत्रापि पक्षे शेषग्रहणं कर्तव्यमित्यर्थः ॥

(९०० दूषणवार्तिकम् ॥ १० ॥)

॥ * ॥ कर्तरि चात्मनेपदविषये परस्मैपदप्रतिषेधार्थम् ॥ * ॥

(भाष्यम्) कर्तरि चात्मनेपदविषये परस्मैपदप्रतिषेधार्थं द्वितीयं शेषग्रहणं कर्तव्यम् । 'शेषाच्छेषे' इति वक्तव्यम् । इह मा भूत्—भिद्यते कुसूलः स्वयमेवेति ॥

(प्रदीपः) कर्तरि चेति । यदा कर्मवदित्ययं शास्त्रातिदेशः, तदा कर्मकर्तरि परत्वात्परस्मैपदं प्राप्नोति । शुद्धौ तु कर्मकर्तारौ उभयोरवकाशौ । कार्यातिदेशे तु परत्वादात्मनेपदं सिध्यति ॥

(उद्द्योतः) शेषग्रहणान्तरं च कर्तव्यमित्यधिकं गौरवं प्रत्ययनियमपक्षे इत्याह—कर्तरि चेति । आत्मनेपदविषयः कर्ता कर्मकर्ता ॥ ननु स्वाश्रयकर्तृत्वप्रयुक्तं परस्मैपदमातिदेशिकेन विरुद्धमिति कथं तत्स्यादत आह—यदेति ॥ परस्मैपदं प्राप्नोतीति । द्वितीयशेषग्रहणे तु कर्मकर्तुः शेषत्वाभावान्नेति भावः ॥ उभयोः, कर्मकर्त्राश्रयविध्योः । भावाभावकृतविरोधवदेव स्वाश्रयं निवर्त्यत इति भावः ॥ न चातिदेशोऽनवकाशः, कार्यान्तरे सावकाशत्वादिति तात्पर्यम् ॥ कार्यातिदेशे त्विति । केचित्त्वेतद्भाष्यप्रामाण्यात्कार्यातिदेशेपि परत्वादिव्यवहारे उत्पत्तिदेश एव देशोतिदिश्यमानकार्याणामित्याहुः ॥ वस्तुतः कार्यातिदेशः शास्त्रातिदेशद्वारैवेत्युक्तम् ॥

(आक्षेपभाष्यम्)

कतरस्मिन्पक्षेऽयं दोषः ? ।

(उद्द्योतः) कर्तरि चेत्यादिचकारस्वारस्यात्प्रकृत्यर्थनियमपक्षे दोषान्तरमिति भाति, तच्च न, वक्ष्यमाणयुक्तेरित्याशयेन पृच्छति—कतरस्मिन्निति ॥

(तृतीयोक्तसमाधानभाष्यम्)

प्रकृत्यर्थनियमे ॥

(उद्द्योतः) भाष्ये चकारस्वारस्येनाह—तृतीयः—प्रकृत्यर्थेति ॥

(तृतीयोक्तसमाधाननिराकरणभाष्यम्)

प्रकृत्यर्थनियमे तावन्न दोषः । प्रकृत्यर्थौ नियतौ, प्रत्यया अनियताः, तत्र नार्थः कर्तृग्रहणेन । कर्तृग्रहणाच्चैष दोषः ॥

(प्रदीपः) प्रकृत्यर्थौ नियताविति । भावकर्मणोरात्मनेपदमेवेति नियमादन्तरेणापि कर्तृग्रहणं कर्तर्येव परस्मैपदं लभ्यत इति नार्थः कर्तृग्रहणेन ॥

(उद्द्योतः) प्रकृत्यर्थनियमवाद्याह—तावन्न दोष इति । अन्तरेणापीति । भावकर्मणोस्तङानयोर्नैयत्येन कर्तर्येवोभयप्रसङ्गात् । उभयप्राप्तौ नियमार्थं शास्त्रं कर्तर्येव पर्यवस्यतीति भावः ॥ भाष्ये—नार्थः कर्तृग्रहणेन कर्तृग्रहणाच्चैष दोष इति । तथा च प्रकृत्यर्थनियमपक्षे तदभावान्नैष दोषः ॥ अयं भावः—यदि कर्तृग्रहणं क्रियते तदा भिन्नविषयत्वाद्भावकर्मणोरिति परस्मैपदापवादो न भवतीति परत्वात्कर्मकर्तरि परस्मैपदं प्राप्नोतीति तन्निवृत्तये शेषग्रहणं कर्तव्यं । यदा तु कर्तृग्रहणं न क्रियते तदा परस्मैपदे प्राप्ते भावकर्मणोरित्यारभ्यमाणं येन नाप्राप्तिन्यायेन शेषादित्यस्यापवाद इति भावकर्मणोरित्येतद्विषये शेषादिति न प्रवर्तत इति कर्मकर्तरि परस्मैपदनिवृत्तये शेषग्रहणं न कर्तव्यमिति ॥

(दोषाश्रयपक्षप्रदर्शकभाष्यम्)

प्रत्ययनियमे तर्ह्ययं दोषः । प्रत्यया नियताः, प्रकृत्यर्थावनियतौ, तत्र कर्तृग्रहणं कर्तव्यं भावकर्मणोर्निवृत्त्यर्थम् । कर्तृग्रहणाच्चैष दोषः ॥

(प्रदीपः) कर्तृग्रहणाच्चेति । परस्तात्तु परिहरिष्यते ॥

(उद्योतः) दोषदः स्वाशयमाह—प्रत्ययनियमे तर्हीति द्वितीयैकर्तृग्रहणाच्चेत्यनेन दोषवानेव प्रत्ययनियमस्तत्करणात्कर्मकर्तर्यतिव्याप्तिश्चेति सूचितं तत्राह—परस्तादिति ॥

(प्रकृत्यर्थनियमेलाघवभाष्यम्)

प्रकृत्यर्थनियमे शेषग्रहणं शक्यमकर्तुम् ॥ कथम् ? । प्रकृत्यर्थौ नियतौ, प्रत्यया अनियताः । ततो वक्ष्यामि—परस्मैपदं भवतीति । तन्नियमार्थं भविष्यति—यत्र परस्मैपदं चान्यच्च प्राप्नोति तत्र परस्मैपदमेव भवतीति ॥

(प्रदीपः) परस्मैपदमिति । सिद्धे परस्मैपदे पुनर्विधानमात्मनेपदनिवृत्त्यर्थं सम्पद्यत इत्यर्थः ॥

(उद्द्योतः) इदानीं प्रकृत्यर्थनियमवादी स्वपक्षे आपादितशेषग्रहणकर्तव्यत्वनिराकरणद्वारा प्रत्ययनियमे तत्करणप्रयुक्तगौरवमाह—प्रकृत्यर्थनियमे इत्यादिना। शेषादिति पञ्चम्यन्तमित्यर्थः॥ सिद्धे इति। तिबादिसूत्रेणेति शेषः। एवं च प्रकृत्यर्थनियमपक्ष एव ज्यायानिति स्थितम्॥

(आक्षेपभाष्यम्)

तत्तर्हि प्रत्ययनियमे द्वितीयं शेषग्रहणं कर्तव्यम्॥

(उद्द्योतः) कर्तृग्रहणं शेषग्रहणं च कुर्वतः पाणिनेः प्रत्ययनियमपक्षे एव तात्पर्यमिति तत्पक्षेपि कर्मकर्तर्यतिव्याप्तिनिरासाय पृच्छति—भाष्ये—तत्तर्हि प्रत्ययेति। सप्तम्यन्तमित्यर्थः॥

(समाधानभाष्यम्)

न कर्तव्यम्। योगविभागः करिष्यते "अनुदात्तङित आत्मनेपदम्"। ततः "भावकर्मणोः"। ततः "कर्तरि" कर्तरि चात्मनेपदं भवति भावकर्मणोः। ततः "कर्मव्यतिहारे" कर्तरीत्येव। भावकर्मणोरिति निवृत्तम्॥

(उद्द्योतः) ततः कर्तरीति। वाक्ये भावकर्मणोरित्यनुवृत्तं कर्तृविशेषणमिति भावः॥

(आक्षेपभाष्यम्)

यथैव तर्हि कर्मणि कर्तरि भवति, एवं भावेपि कर्तरि प्राप्नोति—'एति जीवन्तमानन्दः' 'नास्य किं चिद्रुजतीति॥

(प्रदीपः) नास्य किंचिदिति। पीडारूपं भावस्वभावं वस्त्वित्यर्थः॥ यदि तर्हि कर्मणि कर्तर्यात्मनेपदं भवति हन्यमानो हन्तीत्यत्र प्राप्नोति। नैष दोषः। प्रत्यासत्त्यैकधातुविषयं कर्मकर्तृत्वं विज्ञायते। यस्य स्वाश्रयं कर्तृत्वं कर्मशास्त्रातिदेशाच्चौपचारिकं कर्मत्वं तत्रैव भवति॥

(उद्द्योतः) ननु प्रत्यासत्त्या तद्धात्वर्थनिरूपितकर्मकर्तृत्ववत् तद्धात्वर्थभावकर्तृत्वमेव ग्राह्यम्। एवं च 'एति जीवन्तमानन्द' इत्यत्र कथं दोष इति चेन्न। भावांशे प्रत्यासत्त्याश्रयणस्याशक्यत्वात् तदाह—पीडारूपमिति॥ प्रत्यासत्त्येति। अत्र तु हन्तिभेद इत्यर्थः। तद्धात्वर्थनिरूपितकर्मत्वस्यैव कर्मवद्भावेनातिदेशादिति भावः॥

(समाधानभाष्यम्)

द्वितीयो योगविभागः करिष्यते—"अनुदात्तङित आत्मनेपदम्"। ततः "भावे"। ततः "कर्मणि" कर्मणि चात्मनेपदं भवति। ततः "कर्तरि" कर्तरि चात्मनेपदं भवति। कर्मणीत्यनुवर्तते, भाव इति निवृत्तम्। ततः "कर्मव्यतिहारे" कर्तरीत्येव, कर्मणीति निवृत्तम्॥

(आक्षेपभाष्यम्)

एवमपि शेषग्रहणं कर्तव्यम् "अनुपराभ्यां कृञ" इत्येवमर्थम्। इह मा भूत्—अनुक्रियते स्वयमेव, पराक्रियते स्वयमेव॥

(प्रदीपः) अनुपराभ्यां कृञ इत्येवमर्थमिति। एष हि योगो व्यवहितः। कक्षान्तरप्राप्तत्वादात्मनेपदापवादत्वाच्च बलवानिति न शक्यते योगविभागेन बाधितुम्॥

(उद्द्योतः) व्यवहित इति। एवं चानन्तरस्येतिन्यायेन कर्तरीति योगविभागः शेषात्कर्तरीत्यस्यैव बाधको न त्वनुपराभ्यामित्यस्येति भावः॥ कर्तरीति योगविभागेनानुपराभ्यामित्यस्याबाधे युक्त्यन्तरमप्याह—कक्षान्तरेति। प्रथमं सामान्यतस्तिबादिप्राप्तिः, ततः कर्मवद्भावाद् भावकर्मणोरिति, ततः परत्वात् शेषादिति प्राप्तं कर्तृगामिक्रियाफलाभावेनास्यापि शेषत्वात्, ततो योगविभागादात्मनेपदं प्राप्तं, ततोनुपराभ्यामिति, ततश्चोत्तरकक्षाभावित्वाद्योगविभागस्यापि तद्बाधकमिति न कर्तरीति योगविभागेन तद्बाधनमिति भावः॥ आत्मनेपदापवादत्वाच्चेति। परत्वेन योगविभागबाधकस्वरितञित इति प्राप्तेरित्यर्थः। एवं च बाधकापवादत्वान्नास्य तद्बाध्यत्वमिति भावः॥

(आक्षेपबाधकभाष्यम्)

ननु चैतदपि योगविभागादेव सिद्धम्॥

(प्रदीपः) ननु चैतदपीति। प्राप्तिमात्रं योगविभागेन बाध्यते॥

(उद्द्योतः) प्राप्तिमात्रमिति। बाध्यसामान्यचिन्तयेति भावः॥

(आक्षेपसाधकभाष्यम्)

न सिध्यति। अनन्तरा या प्राप्तिः सा योगविभागेन शक्या बाधितुम्॥ कुत एतत्? अनन्तरस्य विधिर्वा भवति प्रतिषेधो वेति॥ परां प्राप्तिरप्रतिषिद्धा तया प्राप्नोति॥

(उद्द्योतः) भाष्ये परा प्राप्तिरप्रतिषिद्धेति। अबाधितेत्यर्थः॥

(आक्षेपबाधकभाष्यम्)

ननु चेयं प्राप्तिः परां प्राप्तिं बाधते॥

(प्रदीपः) ननु चेयमिति। पूर्वविप्रतिषेधेनेति भावः। शेषादित्यस्यावकाशः याति वातीति। अनुपराभ्यामित्यस्यावकाशः—अशेषः कर्त्रभिप्रायक्रियाफलविषयः—अनुकरोतीति। कर्मकर्तर्युभयप्रसक्ते पूर्वविप्रतिषेधेन शेषादिति प्राप्तिर्भवति। सापि योगविभागेन बाध्यते॥

(उद्द्योतः) ननु 'इयम्' इत्यनेन पूर्वप्रक्रान्तत्वाद्योगविभागरूपाया एव परामर्शः स्यात् स चायुक्त उक्तरीत्या बाध्यबाधकभावस्य वैपरीत्यापत्तेरत इयमित्यनेन शेषादिति प्राप्तिर्ग्राह्या तत्र च बाधकत्वमनुपपन्नमत आह—पूर्वविप्रतिषेधेनेति॥ तदेवाह—शेषादित्यस्यावकाश इति। एवं च तृतीयकक्ष्यायामेव शेषादित्यनेनानुपराभ्यामित्यस्य पूर्वविप्रतिषेधेन बाधे चतुर्थकक्ष्यायां योगविभागप्राप्त्या शेषादिति बाध्यते न च पुनरनुपराभ्यामित्यस्य प्राप्तिः सकृद्गतिन्यायादिति भावस्तदाह—सापि योगविभागेनेति।

(आक्षेपसाधकभाष्यम्)

नोत्सहते प्रतिषिद्धा सती बाधितुम् ॥

(प्रदीपः) **नोत्सहते इति ।** शेषादिति प्राप्तिर्योगविभागेनापवादेन कर्मकर्तृविषयाद्विषयान्तरं नीता नोत्सहते परां प्राप्तिं बाधितुमित्यर्थः ॥ अथ वा—इयं योगविभागप्राप्तिरविशेषा**दनुपराभ्यामि**त्येतामपि प्राप्तिं बाधिष्यत इत्यर्थः ॥ **नोत्सहत इति ।** अपवादापवादत्वादनुपराभ्यामित्येतया प्राप्त्या प्रतिषिद्धा नोत्सहते तामेव बाधितुमित्यर्थः ॥

(उद्द्योतः) **शेषादितीति ।** उत्सर्गापवादयोरेकवाक्यतयाऽपवादविषये उत्सर्गाप्रसक्तेरिति भावः ॥ **परां प्राप्तिमिति ।** कर्मकर्तृविषयामनुपराभ्यामिति प्राप्तिमित्यर्थः ॥ भाष्ये **प्रतिषिद्धे**त्यस्य बाधितेत्यर्थः । पूर्वविप्रतिषेधारम्भे गौरवात् ॥ **इय**मित्यनेन योगविभागप्राप्तिरेव परामृश्यत इत्याह—**अथ वेति ।** बाध्यसामान्यचिन्तयेति भावः ॥ **अपवादापवादत्वादिति ।** पूर्वमपवादपदं बाधकपरं तत्र योगविभागस्य परत्वाद्बाधकं **स्वरितञित** इति तदपवादत्वादित्यर्थः । क्वचित्त्वपवादत्वादित्येव पाठस्तदापि तद्बाधकत्वोपलक्षकं परत्वाद्धि योगविभागस्यानुपराभ्यामिति बाधकम् । भाष्येपि **प्रतिषिद्धे**त्यस्य परत्वाद्बाधितेत्यर्थः ॥

(समाधानभाष्यम्)

एवं तर्हि "कर्तरि कर्मव्यतिहारे" इत्यत्र कर्तृग्रहणं प्रत्याख्यायते । तत्प्रकृतमुत्तरत्रानुवर्तिष्यते —"शेषात्कर्तरि कर्तरि" इति । किमर्थमिदं कर्तरि कर्तरीति ? । कर्तैव यः कर्ता तत्र यथा स्यात् । कर्ता चान्यश्च यः कर्ता तत्र मा भूदिति । ततः "अनुपराभ्यां कृञः कर्तरि कर्तरि" इत्येव ॥ अनुदात्तङित ॥ १२ ॥

(प्रदीपः) **कर्तैव यः कर्तेति ।** यस्य व्यपदेशान्तरं नास्तीत्यर्थः । यद्येवमसिश्छिनत्तीति करणकर्तरि न प्राप्नोति । नैष दोषः ॥ कर्त्रवस्थायां करणत्वाभावात् । भिद्यते कुसूलः स्वयमेवेत्यत्र तु स्वाश्रयं कर्तृत्वमातिदेशिकं तु कर्मत्वमिति न भवति परस्मैपदम् ॥ १२ ॥

(उद्द्योतः) भाष्ये **प्रत्याख्यायते इति ।** वर्तमानसामीप्ये लट् ॥ कर्मकर्तरि वस्तुतः कर्मत्वाभावात्पुनः कर्तृग्रहणेपि नेष्टसिद्धिरत आह—**व्यपदेशान्तरमिति ॥** भाष्ये **कर्ता चान्यश्चेति ।** कर्तृव्यवहारवान्कर्मव्यवहारवांश्चेत्यर्थः ॥ १२ ॥

(१३१ नियमसूत्रम् ॥ १। ३। २। आ० २ सूत्रम्)

१६१ कर्तरि कर्मव्यतिहारे ॥ १।३।१४॥

(९०१ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ क्रियाव्यतिहारे ॥ * ॥

(भाष्यम्) **क्रियाव्यतिहार इति वक्तव्यम् । कर्मव्यतिहार इत्युच्यमाने इहापि प्रसज्येत—देवदत्तस्य धान्यं व्यतिलुनन्तीति, इह च न स्यात्—व्यतिलुनते व्यतिपुनत इति ॥**

(प्रदीपः) **कर्तरि॥१४॥ क्रियाव्यतिहार इति वक्तव्यमिति ।** प्रत्यासन्नत्वात्कृत्रिमस्यैव साधनकर्मणो ग्रहणं प्राप्नोति । साधनकर्मणि च धातोर्वृत्त्यसम्भवाद्धात्वर्थस्य तद्विषयत्वं विज्ञायेत ॥ **देवदत्तस्य धान्यमिति ।** देवदत्तस्वामिकं धान्यं लवनेन स्वीकुर्वन्तीत्यर्थः । क्रियाणां साध्यैकस्वभावानां कथं व्यतिहार इति चेत् योग्यतावशादस्येयं क्रिया साध्या अस्या इदं साधनमिति निर्ज्ञाते साध्यसाधनभावे यो व्यत्यासः स क्रियाव्यतिहारः । परस्परकरणमपि क्वचित् क्रियाव्यतिहारः—यथा सम्प्रहरन्ते राजान इति । अत्रैकैव क्रिया सञ्चारिणीव लक्ष्यते ॥

(उद्द्योतः) **कर्तरि कर्म ॥ १४ ॥** ननु क्रियावचनस्यैव कर्मशब्दस्य लोकप्रसिद्धत्वाद् धात्वन्वये साक्षात्सम्बन्धलाभाच्च तस्यैव ग्रहणं भविष्यतीत्यत आह—**प्रत्यासन्नत्वादिति ।** लोकप्रसिद्ध्यपेक्षया शास्त्रे शास्त्रप्रसिद्धिरेव बलवती प्रकरणादिति भावः ॥ **साधनकर्मणि** ईप्सिततमे ॥ **तद्विषयत्वमिति ।** कर्मव्यतिहारविषयार्थकाद्धातोरित्यर्थ इति भावः ॥ ननु देवदत्तस्वामिकधान्यस्यान्येन लवनेपि तत्स्वत्वानुत्पत्तेर्विनिमयाभावात्कथमत्र प्राप्तिरत आह—**स्वीकुर्वन्तीत्यर्थ इति ।** स्वीकारपर्यन्तं धातोर्लक्षणेति भावः ॥ क्रिययात्र कर्मणः स्वत्वविनिमय एव कर्मविनिमय इति बोध्यम् ॥ **क्रियाणामिति ।** स्थिरेषु द्रव्येष्वन्यसंबन्धिनोऽन्यसंबन्धरूपव्यतिहारसंभवेपि क्षणस्थायिक्रियासु तदसंभव इति भावः ॥ **योग्यतेति ।** नान्यसंबन्धिनोन्यसंबन्धित्वं सः किं त्वन्यदीयत्वेन प्रसक्तस्यान्यसंबन्ध इति भावः । एवं च साधनव्यत्यास एव क्रियाव्यत्यास इति तात्पर्यम् ॥ नन्वेवं स्वस्वक्रियैव स्वेन करणात्संप्रहरन्त इत्यत्र व्यतीहाराभावेनात्मनेपदं न स्यादत आह—**परस्परेति ।** परस्परसंबन्धिकरणमित्यर्थः । संबन्धश्च कर्मकरणसंप्रदानापादानादिलक्षणो बोध्यः ॥ प्रायेण व्यती अस्य द्योतकौ । क्वचित्समपि, यथा संप्रहरन्त इत्यत्र । क्वचित्तु प्रकरणादिकमपि तथा बोध्यम् ॥ नन्वेवमप्येकक्रियानिरूपितकारकशक्तिव्यत्यासो नोपपादितः प्रहाराणां भिन्नभिन्नत्वादित्यत आह—**अत्रेति ।** साधनभेदात्क्रियाभेदावश्यम्भावेन सर्वत्र जातिकृतमेवैक्यमपेक्षणीयमिति भावः ॥ एकधातुवाच्यत्वेन वैकत्वम् ॥

(तृतीयाक्षेपभाष्यम्)

तत्तर्हि वक्तव्यम् ॥

(सिद्धान्तिसमाधानभाष्यम्)

न वक्तव्यम् । क्रियां हि लोके कर्मेत्युपचरन्ति । 'कां क्रियां करिष्यसि' 'किं कर्म करिष्यसी'ति ॥

(प्रदीपः) **क्रियामिति ।** लौकिकाश्चार्था इहानूद्यन्ते ॥

१ 'तस्य' ॥ २ 'क्रियाया' इति भवेत् ॥ ३ 'इह गृह्यते' ॥

(उद्योतः) लौकिका इति । पशुरपत्यं देवतेतिवदिति भावः ॥ इह, शास्त्रे ॥ तदुक्तमुभयगतिरिहेति । कर्मणि द्वितीयेति कृत्रिमम् । अत्र लौकिकं क्रियारूपम् । स्पष्टं चेदं संख्यासंज्ञासूत्रे भाष्ये ॥

(आक्षेपभाष्यम्)

एवमपि कर्तव्यम् । 'कृत्रिमाकृत्रिमयोः कृत्रिमे संप्रत्ययो भवति' ॥

(आक्षेपबाधकभाष्यम्)

क्रियापि कृत्रिमं कर्म ॥

(उद्योतः) इह तु कृत्रिमाकृत्रिमन्यायमेवाभ्युपेत्याह—क्रियापि कृत्रिममिति ॥

(आक्षेपसाधकभाष्यम्)

न सिध्यति । "कर्तुरीप्सिततमं कर्म" इत्युच्यते । कथं च क्रिया नाम क्रियया ईप्सिततमा स्यात्? ॥

(प्रदीपः) कथं च क्रियेति । द्वयोरपि साध्यत्वात्परस्परासम्बन्धं मत्वा प्रश्नः ॥

(उद्योतः) ननु द्वयोरपि क्रिययोः पश्य मृगो धावतीत्यादौ संबन्धो दृश्यत इत्यत आह—मत्वा प्रश्न इति ॥

(सिद्धान्तिसमाधानभाष्यम्)

क्रियापि क्रिययेप्सिततमा भवति ॥ कया क्रियया? । संपश्यतिक्रियया प्रार्थयतिक्रियया अध्यवस्यतिक्रियया [च] । इह य एष मनुष्यः प्रेक्षापूर्वकारी भवति स बुद्ध्या तावत् कंचिदर्थं संपश्यति, संदृष्टे प्रार्थना, प्रार्थिते अध्यवसायः, अध्यवसाये आरम्भः, आरम्भे निर्वृत्तिः, निर्वृत्तौ फलावाप्तिः । एवं क्रियापि कृत्रिमं कर्म ॥

(प्रदीपः) क्रियापीति । भोक्तुमिच्छति भोक्तुं जानातीति दर्शनात् ॥ कया क्रिययेति । क्रियान्तरवाचिप्रयोगाभावात्प्रश्नः ॥ संपश्यति क्रिययेति । सन्दर्शनादीनामव्यभिचारात्प्रतीयमानत्वात्प्रतीयमानक्रियापेक्षया च प्रविश पिण्डीमित्यादौ कर्मादिभावदर्शनात् ॥

(उद्योतः) भोक्तुमिच्छतीति । अव्ययकृत्त्वादयमसत्त्वभूतो भाव इति भावः ॥ भोजनमिच्छतीत्यादि क्रमेणार्थः ॥ ननु क्रियाया अपि जन्यत्वेन किंचित्क्रियासाध्यत्वनिश्चये किमुच्यते कयेत्यत आह—क्रियान्तरेति ॥ भाष्ये संपश्यतिक्रिययेत्यादि । दर्शनक्रियाजन्यं प्रार्थनं तज्जन्याध्यवसायजन्यारम्भेणेत्यर्थः ॥ क्रियया चेति चपाठोऽसांप्रदायिकः ॥ प्रेक्षापूर्वकारी विचारपूर्वं क्रियाकर्ता स बुद्ध्या बुद्धिवृत्त्या तावत् प्रथमं कंचिदर्थं फलरूपं पश्यति । फलविषयसंकल्पोऽत्र दर्शनम् । तज्जन्यः फलोपायविषयोऽभिलाषः प्रार्थना । तज्जन्यः क्रियाविशेषस्य फलसाधनत्वनिश्चयोऽध्यवसायः । अभिलाषे सति तन्निश्चयकरणात् । तज्जन्या मानसी प्रवृत्तिरारम्भः । तज्जन्या क्रियानिर्वृत्तिः । ततः फलावाप्तिरित्यर्थः । फलावाप्तिरित्यनेन दर्शनं फलविषयकमिति सूचितम् । सप्तमीभिस्तृतीयाभिश्च पूर्वपूर्वस्योत्तरकारणता बोधिता । तत्रारम्भस्याप्यमानत्वेन प्रकृतक्रियायाः कर्मत्वम् ॥ अव्यभिचारादिति । स चोक्तविभक्तिभिर्भाष्ये दर्शितः ॥

(आक्षेपसाधकभाष्यम्)

एवमप्युभयोः कृत्रिमयोरुभयगतिः प्रसज्येत । तस्मात्क्रियाव्यतिहार इति वक्तव्यम् ॥

(आक्षेपबाधकसमाधानसाधकभाष्यम्)

न वक्तव्यम् । इह "कर्तरि व्यतिहारे" इतीयता सिद्धम् । सोयमेवं सिद्धे सति यत्कर्मग्रहणं करोति तस्यैतत्प्रयोजनम्—क्रियाव्यतिहारे यथा स्यात्कर्मव्यतिहारे माभूदिति ॥

(प्रदीपः) इह कर्तरीति । क्रियायाः साध्यत्वात्प्राधान्यात्क्रिययाप्तुमिष्टतमत्वात्तादर्थ्येन क्रियाप्रवर्तनात्कर्मणोपि प्राधान्यादुभयव्यतिहारे लब्धे कर्मग्रहणात् क्रियाव्यतिहारोयं गृह्यते क्रियायाः धातुवाच्यत्वादन्तरङ्गत्वात् ॥

(उद्योतः) ननु कर्मग्रहणाभावे करणादिव्यतीहारोपि गृह्येतेत्यत आह—क्रियाया इति । साध्यत्वेन प्रतीयमानत्वात् शाब्दं प्राधान्यं क्रियायाः, क्रियोद्देश्यत्वलक्षणम् आर्थप्राधान्यं च कर्मकारकस्यैवेति तयोरेव ग्रहणं न करणादेरिति भावः ॥ कर्मग्रहणेन क्रियामात्रग्रहणे उपायमाह—क्रियाया इति । कारकपरत्वे कर्मेति कर्मणि प्रत्ययः कार्यः, क्रियापरत्वे तु भावे । भावश्चान्तरङ्ग इति भावः ॥

(कर्तृग्रहणप्रयोजनाधिकरणम्)

(आक्षेपभाष्यम्)

अथ कर्तृग्रहणं किमर्थम्? ।

(९०२ प्रयोजनवार्तिकम् ॥ २ ॥)

॥ * ॥ कर्मव्यतिहारादिषु कर्तृग्रहणं भावकर्मनिवृत्त्यर्थम् ॥ * ॥

(भाष्यम्) **कर्मव्यतिहारादिषु कर्तृग्रहणं क्रियते भावकर्मणोरनेनात्मनेपदं मा भूदिति ॥**

(उद्योतः) भाष्ये—कर्मव्यतिहारादिष्विति । आदिमग्रहणं शेषात्कर्तरीत्यतः प्रागनुवृत्तावपि फलाभावप्रतिपादनार्थम् ॥

(९०३ अन्यथानुपपत्तिवार्तिकखण्डम् ॥ २)

॥ * ॥ इतरथा हि तत्र प्रतिषेधे भावकर्मणोः प्रतिषेधः ॥ * ॥

(भाष्यम्) **अक्रियमाणे कर्तृग्रहणे भावकर्मणोरप्यात्मनेपदमनेन प्रसज्येत ॥ तत्र को दोषः? । तत्र प्रतिषेधे भावकर्मणोः प्रतिषेधः । तत्र प्रति-**

षेधे भावकर्मणोरप्यनेनात्मनेपदस्य प्रतिषेधः प्रसज्येत—व्यतिगम्यन्ते ग्रामाः व्यतिहन्यन्ते दस्यव इति ॥

(प्रदीपः) तत्र प्रतिषेध इति । कर्मव्यतिहारे न गतिहिंसार्थेभ्य इत्यनेन प्रतिषेध इत्यर्थः ॥ १४ ॥

(उद्द्योतः) भावकर्मणोरप्यनेनेति । विहितस्येति शेषः॥ १४॥

(९०४ अन्यथानुपपत्तिबाधकवार्तिकम् ॥ ३ ॥)

॥ * ॥ न वानन्तरस्य प्रतिषेधात् ॥ * ॥

(भाष्यम्) न वा एष दोषः ॥ किं कारणम्? । अनन्तरस्य प्रतिषेधात् । अनन्तरं यदात्मनेपदविधानं तस्य प्रतिषेधात् । कुत एतत्? । 'अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा' इति । पूर्वा प्राप्तिरप्रतिषिद्धा तया भविष्यति ॥

(प्रयोजनसाधकभाष्यम्)

ननु चेयं प्राप्तिः पूर्वां प्राप्तिं बाधते ॥

(प्रयोजनबाधकभाष्यम्)

नोत्सहते प्रतिषिद्धा सती बाधितुम् ॥

(प्रयोजनान्तरभाष्यम्)

उत्तरार्थं तर्हि कर्तृग्रहणं कर्तव्यम् ॥

(प्रयोजनान्तरबाधकभाष्यम्)

न कर्तव्यम् । क्रियते तत्रैव "शेषात्कर्तरि परस्मैपदम्" इति ॥

(प्रयोजनान्तरसाधकभाष्यम्)

द्वितीयं कर्तृग्रहणं कर्तव्यम् ॥ किं प्रयोजनम्? । कर्तैव यः कर्ता तत्र यथा स्यात्, कर्ता चान्यश्च यः कर्ता तत्र मा भूदिति ॥ कर्तरि कर्म ॥ १४ ॥

(१३२ निषेधसूत्रम् ॥ १ । ३ । २ आ. ३ सू.)

१६२ न गतिहिंसार्थेभ्यः ॥ १।३।१५ ॥

(न्यूनतापूर्त्यधिकरणम्)

(९०५ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ प्रतिषेधे हसादीनामुपसंख्यानम् ॥ * ॥

(भाष्यम्) प्रतिषेधे हसादीनामुपसंख्यानं कर्तव्यम् ॥ व्यतिहसन्ति । व्यतिजल्पन्ति । व्यतिपठन्ति ॥

(प्रदीपः) न गति ॥ १५ ॥ हसादीनामिति । हसिप्रकाराणां शब्दक्रियाणामित्यर्थः ॥

(उद्द्योतः) न गति ॥ १५ ॥ हसादीनामित्यादिशब्दस्य व्यवस्थार्थत्वे हसेरुत्तरेषां धातुपाठपठितानां ग्रहणं स्यादत आह—हसीति । पठन्तीतिभाष्योदाहरणादाह—शब्दक्रियाणामिति । अशब्दहासे भवति नवेति बहुदर्शिनो विचारयन्तु ॥

(९०६ आक्षेपवार्तिकम् ॥ २ ॥)

॥ * ॥ हरिवह्योरप्रतिषेधः ॥ * ॥

(भाष्यम्) हरिवह्योरप्रतिषेधो भवतीतिवक्तव्यम् ॥ संप्रहरन्ते राजानः । संविवहन्ते गर्गैरिति ॥

(प्रदीपः) हरिवह्योरिति । हरतेर्हिंसार्थत्वाद्वहतेर्गत्यर्थत्वात्प्राप्तिः ॥ 'ततः संप्रहरिष्यन्तौ दृष्ट्वा कर्णधनंजयौ' इत्यत्र व्यतिहारो न विवक्षितः किं तर्हि योत्स्यमानावित्येतावद्विवक्षितम् ॥

(उद्द्योतः) हृवह्योरित्येव पाठः । हरिवह्योरितिपाठ इत एव निर्देशादिकः कित्त्वेपि गुणः । कृतगुणानुकरणाद्वा इगिति कल्प्यम् ॥ योत्स्येति । संप्रहारशब्दस्य युद्धेपि रूढत्वादिति भावः॥

(वहिग्रहणप्रत्याख्यानभाष्यम्)

न वहिर्गत्यर्थः । देशान्तरप्रापणक्रियोत्र वहिः ॥ न गति ॥ १५ ॥

(प्रदीपः) देशान्तरप्रापणक्रिय इति । भारं वहतीत्यादौ देशान्तरप्राप्त्युपसर्जनं प्रापणमस्य वाच्यम् । तत्र तु गतिर्नान्तरीयकत्वात्प्रतीयते न त्वसौ धात्वर्थः । अस्यैव न्यायसिद्धार्थस्यानुवादकमर्थग्रहणम् । गर्गाणां तु प्रापणं कन्याद्वारकमिति वहेर्गत्यर्थत्वाभावः ॥ १५ ॥

(उद्द्योतः) वार्तिकस्थवहिग्रहणं प्रत्याचष्टे भाष्ये—न वहिरित्यादिना ॥ नान्तरीयकत्वादिति । ग्रामं प्राप्त इत्यादौ देशान्तरप्राप्तेर्गतिं विनाऽनुपपत्तेरिति भावः ॥ प्राप्तिस्तु संबन्धमात्रं, न संयोग एव, देशान्तरस्थेपि 'भूरनेन प्राप्ता' इति व्यवहारात् । ग्रामं प्राप्तवानित्यादौ संयोगमूलकाधाराधेयभावः प्राप्तिः । क्वचित्तत्र स्थितिरेव प्राप्तिः । द्वितीयाश्रितेत्युदाहरणे सुखप्राप्त इत्यादावादिकर्मणि क्तः कर्तरि चेति कर्तरि क्तो बोध्यः ॥ नान्तरीयकतया प्रतीयमानस्यापि तदर्थत्वाभिमानेन वार्तिकारम्भः ॥ तत्रैव मानमाह—अस्यैवेति । अन्यथा 'न गतिहिंसयोः' इत्येव वदेत् । गतिहिंसयोर्वर्तमानेभ्यो धातुभ्य इत्यर्थ इति भावः ॥ भाष्योक्तोदाहरणेपि गत्यर्थत्वाभावं दर्शयति—गर्गाणां त्विति । प्रापणं, संबन्धः ॥ कन्याद्वारकमिति । कन्याप्राप्तिफलकपाणिग्रहणद्वारकसंबन्धो विवाह इत्यर्थः ॥ गर्गैरिति तृतीया तु सहार्थे बोध्या । गर्गैः सह कन्याद्वारकं संबन्धं प्राप्नुवन्तीत्यर्थः । भाष्ये देशान्तरग्रहणमुपलक्षणमिति तात्पर्यम् ॥ १५ ॥

(१३३ निषेधसूत्रम् ॥ १। ३। २ आ. ४ सू०)

१६३ इतरेतरान्योन्योपपदाच्च ॥ १।३।१६ ॥

(न्यूनतापूरणाधिकरणम्)

(९०७ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ परस्परोपपदाच्च ॥ * ॥

(भाष्यम्) परस्परोपपदाच्चेति वक्तव्यम्। परस्परस्य व्यतिलुनन्ति। परस्परस्य व्यतिपुनन्ति॥ इतरेतरा० ॥ १६ ॥

(प्रदीपः) इतरेतरा ॥ १६ ॥ लौकिके शब्दव्यवहारे लाघवानादरादितरेतरादिशब्दा उपसर्गाश्च कर्मव्यतिहारद्योतनाय प्रयुज्यन्ते ॥ १६ ॥

(उद्योतः) इतरेतरा ॥ १६ ॥ नन्वितरेतरशब्देनैव कर्मव्यतिहारस्य द्योतितत्वादुक्तार्थानामितिन्यायेनात्रात्मनेपदाप्रसक्तिरत आह—लौकिक इति। लाघवादरानादरयोः प्रयोगानुसार एव बीजमिति भावः ॥ उपपदशब्दश्चात्र यौगिको न तु रूढः ॥ १६ ॥

(१३४ आत्मनेपदनियमसूत्रम् ॥ १। ३। २ आ. ५ सू.)

१६६ विपराभ्यां जेः ॥ १।३।१९ ॥

(अनिष्टवारणाधिकरणम्)

(९०८ आक्षेपवार्तिकम् ॥ १ ॥)

[॥ * विपराभ्यामित्युपसर्गग्रहणम् * ॥]

(भाष्यम्) [विपराभ्यामिति] उपसर्गग्रहणं कर्तव्यम्। इह मा भूत्—पराजयति सेनेति ॥

(तृतीयाक्षेपभाष्यम्)

तत्तर्हि वक्तव्यम् ॥

(सिद्धान्तिसमाधानभाष्यम्)

न वक्तव्यम्। यद्यपि तावदयं पराशब्दो दृष्टापचार उपसर्गश्चानुपसर्गश्च, अयं खलु विशब्दोऽदृष्टापचार उपसर्ग एव। तस्यास्य कोऽन्यो द्वितीयः सहायो भवितुमर्हत्यन्यदत उपसर्गात्। तद्यथा—'अस्य गोर्द्वितीयेनार्थः' इति गौरेवोपादीयते नाश्वो न गर्दभ इति ॥ विपराभ्याम् ॥ १९ ॥

(प्रदीपः) विपराभ्यां ॥१९॥ विशब्द इति। पक्षिवाची तु यो विशब्दः तस्य नपुंसकत्वाभावात्पुंसि विभक्त्या व्यवधानाद्वेरनन्तरो जयतिर्न सम्भवति। बहुवि जयति वनमित्यत्र जहत्स्वार्थायां वृत्तौ वेरानर्थक्यादिह चार्थवतो ग्रहणादजहत्स्वार्थायामपि तदर्थस्योपसर्जनत्वादग्रहणम्। संबुद्ध्यन्तं तु वे इति रूपान्तरयुक्तत्वान्न गृह्यते। एकदेशविकृतस्यानन्यत्वाद्विशब्द एवायमिति चेत्। विरित्यस्य विभक्त्यन्तस्य वे इति विकारो न तु विशब्दस्येत्यदोषः॥ वी जयत इत्यत्र एकादेशस्य पूर्वं प्रत्यन्तवद्भावाद्विशब्दात्परो जयतिः सम्भवत्येवेति चेत्। पूर्वस्य कार्ये कर्तव्येऽन्तवद्भावः। न चात्र पूर्वस्य किंचित्कार्यमित्यदोषः ॥ अस्य गोरिति। द्वितीयशब्दो लोके प्रयुज्यमानो यदपेक्षं द्वितीयत्वं तत्तुल्यजातीय एव सम्प्रत्ययं करोति। एवमिहापि विशब्दसाहचर्यात्पराशब्दोप्युपसर्गो गृह्यते ॥ पक्षिवाचिनो विशब्दस्य सम्भवे तु द्वयोरपि दृष्टापचारत्वात्परस्परसाहचर्यादुपसर्गग्रहणं व्याख्येयम् ॥ १९ ॥

(उद्योतः) विपराभ्यां जेः ॥ १९ ॥ भाष्ये—दृष्टापचार इति। दृष्टव्यभिचारो दृष्टोपसर्गत्वाभाववानिति यावत् ॥ पक्षिवाचकविशब्दस्यानुपसर्गस्यापि सत्त्वादाह—पक्षीति ॥ इह चेति। उपसर्गस्तु द्योत्यार्थेनार्थवानेवेति भावः ॥ इदं चिन्त्यम्। तत्पक्षे भौतपूर्विकार्थवत्त्वस्यैव ग्रहणात्। शुद्धरूढातिरिक्ते जहत्स्वार्थत्वाभावाच्च ॥ विभक्त्यन्तस्येति। संबुद्धिगुणस्य विभक्त्युत्पत्त्यनन्तरं प्रवृत्तेरित्यभिमानः ॥ ननु विभक्त्युत्पत्त्यनन्तरं गुणप्रवृत्तावपि विशब्दान्त्यवर्णावच्छेदेन विकारसत्त्वात् तस्याप्येकदेशविकृतत्वमस्त्येवेति चेत् चिन्त्यमेवैतत् ॥ पूर्वस्य कार्ये इति। चिन्त्यमिदम्। हे ज्ञानेत्यादौ संबुद्धिहल्लोपेऽपि पूर्वस्यान्तवद्भावानापत्तेः, सर्वासामित्यत्र सुडनापत्तेश्च ॥ भाष्यं त्वित्थं व्याख्येयम्—विशब्द इत्यस्य जयतिसंबद्ध इत्यादिः। तेन जयतिसंबद्धो विशब्दोऽदृष्टापचारोऽदृष्टान्यार्थक इत्यर्थः। ईदृशप्रयोगाणां काप्यदर्शनादिति ॥ कुतोन्यत्वं तदाह—अन्यदत इति। अत उपसर्गादन्यत्वमित्यर्थः ॥ ननु पूरणप्रत्ययान्तस्य सजातीयविषयत्वेपि प्रकृते किमायातमत आह—द्वितीयेति। दृष्टान्तार्थं स इति भावः ॥ यदपेक्षं द्वितीयत्वमिति। यदीयं सहायत्वमित्यर्थः। द्वितीयशब्दः सहायवाची। एवं च यथा लोकः स्वसजातीयमेव सहायमुपादत्ते, एवं शब्दोपि प्रयोगे सहायं सजातीयमेवोपादत्ते न विजातीयम् ॥ एतन्मूलिकैव सहचरितासहचरितयोः सहचरिते संप्रत्ययपरिभाषा। तत्र सहचरितत्वं सदृशत्वमेवेति दिक् ॥ संभवेत्विति। वी जयतः वे जयसीत्यादौ। अत्र तुना पूर्वोक्तप्रयोगाभावरूपस्तदसंभवो ध्वनितः ॥ परस्परेति। विशब्दसाहचर्यात् पराशब्दोऽदृष्टावन्तः प्रसिद्धो गृह्यते तत्साहचर्याच्च विरुपसर्ग एवेति भावः ॥ प्रकृतिवदनुकरणमित्यस्यानित्यत्वाज्जेरित्यत्रेयङ्भावः ॥ १९ ॥

(१३५ आत्मनेपदनियमसूत्रम् ॥ १। ३। २ आ. ६ सू.)

१६७ आङो दोनास्यविहरणे ॥ १।३।२० ॥

(अनिष्टनिवारणाधिकरणम्)

(९०८ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ आङो दोऽव्यसनक्रियस्य ॥ * ॥

(भाष्यम्) आङो दोऽव्यसनक्रियस्येति वक्त-

ष्यम् । इहापि यथा स्यात्—विपादिकां व्याददाति कूलं व्याददातीति ॥

(प्रदीपः) आङो दो ॥२०॥ **अव्यसनक्रियस्येति ।** व्यसनं विभागः विकासनमित्यर्थः । केवलो विहरणशब्द उपादीयमानः पादविहरणं गमयतीत्यास्यग्रहणं सूत्रे कृतम् । केवलो व्यसनशब्दो दुःखादिषु वर्तत इति वार्तिके क्रियाग्रहणं कृतम् ॥

(उद्योतः) आङोदो ॥ २० ॥ **विभाग इति ।** व्यसनशब्दस्य पीडायां रूढत्वेपि ददातेः पीडार्थकत्वासंभवेन निषेधवैयर्थ्यात्स न गृह्यते इत्यर्थः ॥ विभागशब्देन तदनुकूलव्यापारो गृह्यते तदाह —**विकासनमिति ॥ पादविहरणमिति ।** इदमुपलक्षणमग्नीन् विहरेत्यादौ प्रज्वलनस्य, 'विहारशय्यासनभोजनेष्वित्यादौ लीलायाश्च प्रतीतेः। अत एव वेः **पादविहरण** इत्यत्र पादग्रहणं चरितार्थम् ॥ **दुःखादिष्विति ।** 'व्यसनं विपदि भ्रंशे दोषे कामजकोपजे' । इति कोशाद् दुःखादिसंबन्धिक्रियावृत्तेरपि प्रतीतिप्रसङ्ग इति भावः । क्रियाग्रहणे तु व्यसनरूपक्रियावाचकस्यैव ग्रहणाद्विभागार्थकत्वलाभः । स्वरूपतो दुःखादिकं तु न क्रिया, नापि धातुवाच्यमिति बोध्यम् ॥ **विपादिकां व्याददातीति ।** विपादिकावृत्तिविभागानुकूलो व्यापार एककर्तृक इति बोधः ॥

(तदस्याक्षेपभाष्यम्)

तत्तर्हि वक्तव्यम् ॥

(सिद्धान्तिसमाधानभाष्यम्)

न वक्तव्यम् । इह "आङो दोनास्य" इतीयता सिद्धम् । सोयमेवं सिद्धे सति यद्विहरणग्रहणं करोति तस्यैतत्प्रयोजनम्—आस्यविहरणसमानक्रियादपि यथा स्यात् । यथाजातीयका चास्यविहरणक्रिया तथाजातीयकात्रापि ॥

(प्रदीपः) **आङो दोनास्य इति ।** आस्यसमवायिन्यां क्रियायां ददातिर्वर्तमान आस्यवृत्तिर्भवति । यथा लोमविषयहर्षणवृत्तिर्हृषिर्लोमसु वर्तत इत्युच्यते॥ ददातेरेवास्ये वृत्तिसम्भवो नान्येषां दारूपाणामिति तेषामिह ग्रहणाभावः ॥ यद्येवं स्वं मुखमादत्त इत्यत्रापि मुखविषयत्वादादानस्य प्रतिषेधः प्राप्नोति । नैष दोषः । आस्यसमवेतैव या क्रिया तस्यां वृत्तो ददातिरास्ये वृत्तो भवति । ग्रहणं तु प्राप्यग्रहीतृविषयम् । अनास्य इति च पर्युदासः । आस्यानास्यसमुदायश्चास्यसदृश इति विधिरेव तत्र भवति ॥ **सोयमिति ।** आस्यग्रहणं विहरणविशेषोपलक्षणार्थमित्यसत्यप्यास्ये विहरणसद्भावाभिषेधो भवति ॥

(उद्योतः) आस्यस्य द्रव्यत्वात्कथं तत्र धातोर्वृत्तिरत आह —**आस्येति ।** आस्यवृत्तिविभागानुकूलव्यापारे इत्यर्थः ॥ नन्वेवमास्यसमवेतक्रियेतरार्थवृत्तेर्दाधातोरित्यर्थे गामादाग्रहणेष्वविशेषात्सर्वदाशब्दानां ग्रहणं स्यादत आह—**ददातेरेवेति ।** आङ्पूर्वस्येति शेषः ॥ **नान्येषामिति ।** अनभिधानादिति भावः । एतेन शोधनखण्डनादीनामप्यास्यसमवेतक्रियात्वाविशेषादन्येषामपि दारूपाणां ग्रहणं प्राप्नोतीति परास्तम् ॥ **आस्यसमवेतैवेति ।** आस्यमात्रसमवेतफलजनकक्रियावृत्तेर्नेत्यर्थः । आस्यमात्रसमवेतफलजनकक्रियालक्षकास्यशब्देन च नञ्समासः । एवं च स्वं मुखमित्यादौ न दोषः । तदर्थफलस्य संयोगस्य कर्तृकर्मोभयसमवेतत्वात् ॥ न्याय्यत्वादाह—**पर्युदास इति ।** तेन मुखविपादिके व्यादत्ते इत्येव ॥ वस्तुतः प्रसज्यप्रतिषेध एव । प्रतिषेधे एव स्वाङ्गकर्मकादित्यस्यान्वयसंभवात् प्रत्युदाहरणभाष्येण तस्य तत्सम्बन्धस्यैव बोधनात् । नहि विधिशेषत्वे तत्प्रत्युदाहरणं संभवतीति परे ॥ **विहरणविशेषेति ।** विकासरूपेत्यर्थः । आस्ये दृष्टं विहरणमित्यर्थादिति भावः ॥ अत एव **यथाजातीयके**त्यादिभाष्यं संगच्छते ॥

(९०९ आक्षेपवार्तिकम् ॥ २ ॥)

॥ * ॥ स्वाङ्गकर्मकाच्च ॥ * ॥

(भाष्यम्) स्वाङ्गकर्मकाच्चेति वक्तव्यम् ॥ इह मा भूत्—व्याददते पिपीलिकाः पतङ्गस्य मुखम्' इति ॥ आङो दो ॥ २० ॥

(प्रदीपः) **स्वाङ्गकर्मकादिति ।** स्वमङ्गं स्वाङ्गम्, न तु पारिभाषिकम्—**'अद्रवं मूर्तिमत् स्वाङ्गम्'** इति । तेन परकीयास्यविहरणे विधिरेव भवति ॥ २० ॥

(उद्योतः) **न तु पारिभाषिकमिति ।** कृत्रिमत्वाद्गुरुत्वाच्च यद्यपि तस्यैव ग्रहणं न्याय्यं तथापि व्याख्यानाल्लक्ष्यानुसाराच्चेदमेव गृह्यत इति भावः ॥ **स्वाङ्गकर्मकादिति** पञ्चमीनिर्देशाद् अव्यसनक्रियस्येतिषष्ठीनिर्देशाच्च सूत्रस्थद इति पदं पञ्चम्यन्तं षष्ठ्यन्तं चाऽस्त्विति वार्तिककारो मन्यते ॥ २० ॥

(१३६ आत्मनेपदनियमसूत्रम् । १ । ३ । २ आ. ७ सू.)

१६८ क्रीडोऽनुसंपरिभ्यश्च ॥१।३।२१॥

(अनिष्टवारणाधिकरणम्)

(९१० आक्षेपवार्तिकम् ॥ १ ॥)

[॥ * ॥ उपसर्गग्रहणम् ॥ * ॥]

(भाष्यम्) उपसर्गग्रहणं कर्तव्यम् ॥ इह मा भूत्—'अनु क्रीडति माणवकम्' इति ॥

(प्रदीपः) क्रीडोऽनु ॥२१॥ **अनुक्रीडतीति । तृतीयार्थे** इत्यनुः कर्मप्रवचनीयसंज्ञः । माणवकेन सह क्रीडतीत्यर्थः ॥ एतच्च समा साहचर्याल्लभ्यते ॥

(उद्योतः) क्रीडोनुसं ॥ २१ ॥ **कर्मप्रवचनीयेति ।** धात्वर्थविशेषकत्वे तु धातोरकर्मकत्वान्माणवकमिति द्वितीयानापत्तिरिति भावः ॥

(९११ आक्षेपवार्तिकम् ॥ २ ॥)

॥ * ॥ समोऽकूजने ॥ * ॥

(भाष्यम्) समोऽकूजन इति वक्तव्यम् ॥ इह मा भूत्—संक्रीडन्ति शकटानि ॥

(न्यूनतापूरणाधिकरणम्)

(९१२ आक्षेपवार्तिकम् ॥ ३ ॥)

॥ * ॥ आगमेः क्षमायाम् ॥ * ॥

(भाष्यम्) आगमेः क्षमायामुपसंख्यानं कर्तव्यम् ॥ माणवक आगमयस्व तावत् ॥

(प्रदीपः) आगमयस्वेति ॥ सहस्व कंचित्कालम्, मा त्वरिष्ठा इत्यर्थः ॥

(उद्द्योतः) आगमेरिति वार्तिके गमेर्ण्यन्तस्य निर्देश इति बोध्यम् । मा त्वरिष्ठा इति । अध्ययनार्थं कंचित्कालं क्षमस्व मा त्वरां कुर्वित्यर्थः ॥

(९१३ आक्षेपवार्तिकम् ॥ ४ ॥)

॥ * ॥ शिक्षेर्जिज्ञासायाम् ॥ * ॥

(भाष्यम्) शिक्षेर्जिज्ञासायामुपसंख्यानं कर्तव्यम् । विद्यासु शिक्षते धनुषि शिक्षते ॥

(प्रदीपः) शिक्षेरिति ॥ केचिदाहुः—शकिः सन्नन्तो गृह्यते इति विध्यर्थमिदम् ॥ क्रियाविषयकश्च शकिः प्रयुज्यते—भोक्तुं शक्नोति शयितुं शक्नोति इति प्रयोगदर्शनात् ॥ इह तु जिज्ञासाविषयः शकिर्गृह्यते विद्यां जिज्ञासितुं घटत इत्यर्थः । आत्मनेपदेनैव जिज्ञासाया अवगमाज्जिज्ञासितुमिति न प्रयुज्यते ॥ अन्ये तु 'शिक्ष विद्योपादाने' इत्यस्य ग्रहणं नियमार्थं वर्णयन्ति ॥ विधेरेव तु ज्यायस्त्वात्सन्नन्तशकिग्रहणं न्याय्यम् ॥

(उद्द्योतः) शिक्षेरिति । शकेः सनि सनि मीमेतीस्भावेऽभ्यासलोपे स्कोरिति लोपे षत्वे इक्प्रत्यये शिक्षेरिति निर्देशः ॥ नन्वेवं जिज्ञासायामित्यसङ्गतं, ज्ञानेच्छा हि तदर्थः । लक्ष्ये तु ज्ञानं शक्तौ विषयः, शक्तिः सनर्थेच्छायामिति चेन्न । ज्ञानविशिष्टायाः शक्तेरिच्छाविषयतया ज्ञानस्यापि तत्त्वानपायात् ॥ इयांस्तु विशेषः, इच्छा सनर्थः, शक्तिः प्रकृत्यर्थः, तस्य ज्ञानविषयत्वमात्मनेपदद्योत्यमिति ॥ तदाह—केचिदिति ॥ ननु प्रतिपदोक्तशिक्षेरेव ग्रहणं युक्तमत आह—विध्यर्थमिति । एवं च विधित्वानुरोधेनैव परिभाषात्याग इति भावः ॥ नन्वेवं शक्तीच्छावाचकस्य शिक्षेः कथं जिज्ञासायां वृत्तिरत आह—क्रियाविषयश्चेति । एवं च जिज्ञासाविशेषणीभूतज्ञानविषयकत्वेन जिज्ञासाविषयकत्वं तस्य । जिज्ञासायामिति च विषयसप्तमीति भावः ॥ तदाह—इहेति । जिज्ञासितुमिति । जिज्ञासाविषयज्ञानार्थशक्तौ जिज्ञासार्थस्यारोपः । वार्तिककृता शिक्षेः सनन्तस्य ग्रहणमिति ज्ञापयितुं जिज्ञासाया विषयत्वेन निर्देशः कृत इति बोध्यम् । विद्याविषयज्ञानफलकशक्तीच्छेति बोधः । आत्मनेपदसमभिव्याहारे सन्प्रकृतेः शकेर्ज्ञानविषयशक्तिबोधकत्वमिति तात्पर्यम् ॥ जिज्ञासायाः इच्छाविशेषणीभूतज्ञानस्य ॥ विधेरेव त्विति । शिक्षेरनुदात्तेत्त्वेनात्मनेपदस्य सिद्धत्वादित्यर्थः ॥

(९१४ आक्षेपवार्तिकम् ॥ ५ ॥)

॥ * ॥ किरतेर्हर्षजीविकाकुलायकरणेषु ॥ * ॥

(भाष्यम्) किरतेर्हर्षजीविकाकुलायकरणेषूपसंख्यानं कर्तव्यम् । अपस्किरते वृषो हृष्टः । अपस्किरते कुक्कुटो भक्षार्थी । अपस्किरते श्वा आश्रयार्थी ॥

(प्रदीपः) किरतेरिति । विक्षेपार्थः किरतिः । हर्षादयस्तु विषयत्वेनोपात्ताः ॥ हर्षादिष्वेव अपाच्चतुष्पादिति सुड्विधीयते ॥

(उद्द्योतः) विषयत्वेनेति । तत्र हर्षः कारणं जीविकाकुलायकरणे फले इति विवेकः ॥ हृष्टा बाला धूलिमपकिरन्तीत्यत्रापि स्यादत आह—हर्षादिष्वेवेति । हर्षादिपूर्वकालेखन एवेत्यर्थः । इहालेखनाभावान्न सुट् । शब्दशक्तिस्वभावात्तु तद्विषय एवात्मनेपदमिति भावः ॥

(९१५ आक्षेपवार्तिकम् ॥ ६ ॥)

॥ * ॥ हरतेर्गतताच्छील्ये ॥ * ॥

(भाष्यम्) हरतेर्गतताच्छील्ये उपसंख्यानं कर्तव्यम् । पैतृकमश्वा अनुहरन्ते । मातृकं गावोऽनुहरन्ते ॥

(प्रदीपः) हरतेरिति । गतं प्रकारः ॥ पैतृकमिति । पितुरागतं प्रकारं सततं शीलयन्तीत्यर्थः ॥ मातुरनुहरतीत्यत्र सादृश्यमात्रं विवक्षितम्, न तु प्रकारताच्छील्यमित्यात्मनेपदं तद्धितार्थेत्यत्र भाष्यकारेण न कृतम् ॥

(उद्द्योतः) ताच्छील्यमविच्छेदेन शीलनं तदाह—सततमिति ॥ पैतृकमित्यत्र तत आगत इत्यधिकारे ऋतष्ठञ् । ताच्छील्ये किम् । रावणमनुहरति नटः ॥

(९१६ आक्षेपवार्तिकम् ॥ ७ ॥)

॥ * ॥ आशिषि नाथः ॥ * ॥

(भाष्यम्) आशिषि नाथ उपसंख्यानं कर्तव्यम् । सर्पिषो नाथते मधुनो नाथते ॥

(प्रदीपः) आशिषि नाथ इति । आशिष्येव नाथ इति नियमार्थमिदम् ॥ **सर्पिषो नाथते इति ।** सर्पिर्मे भूयादित्याशास्त इत्यर्थः ॥

(उद्द्योतः) नाथतेरनुदात्तेत्त्वाद्वचनानर्थक्यमत आह—**आशिष्येवेति ।** इदं भूयादितीच्छा आशीः । तत्प्रयुक्तः परदित्सानुकूलो व्यापारो याच्नेत्याशीर्याचनयोर्भेदः । अस्यानुदात्तेत्त्वं तु युजर्थमिति बोध्यम् ॥

(९१७ आक्षेपवार्तिकम् ॥ ८ ॥)

॥ * ॥ आङि नुप्रच्छ्योः ॥ * ॥

(भाष्यम्) आङि नुप्रच्छ्योरुपसंख्यानं कर्तव्यम् । आनुते शृगालः । आपृच्छते गुरुमिति ॥

(प्रदीपः) आनुत इति । उत्कण्ठापूर्वकं शब्दं करोतीत्यर्थः ॥

(उद्द्योतः) शब्दं करोतीति । स्तुत्यर्थकोपि नुराङ्पूर्व उत्कण्ठापूर्वकशब्दमात्रे रूढ इति भावः ॥

(९१८ आक्षेपवार्तिकम् ॥ ९ ॥)

॥ * ॥ शप उपलम्भने ॥ * ॥

(भाष्यम्) शप उपलम्भनउपसंख्यानं कर्तव्यम् । देवदत्ताय शपते । यज्ञदत्ताय शपते । क्रीडोनु॥२१॥

(प्रदीपः) शप उपलम्भन इति । उपलम्भनं प्रकाशनम् ॥ **देवदत्ताय शपत इति । श्लाघह्नुङिति** सम्प्रदानसंज्ञा ॥ ईप्स्यमाने विवदन्ते । केचिदाहुः—यस्मा आख्यायते स सम्प्रदानम् ॥ य आख्यायते स इत्यन्ये ॥२१॥

(उद्द्योतः) शपतिर्नानार्थः । अस्त्याक्रोशे, देवदत्तं शपतीति । निन्दतीत्यर्थः । अस्ति तत्त्वावेदनपूर्वकं तत्प्रत्यायनाय भाषणादेः क्वचिद्धस्तादिना साक्षात्स्पर्शरूपे मानसस्पर्शरूपे वा शपथे, यथा—विप्रैः शपे क्षात्रधर्मेण शपे इत्यादौ । तृतीया तु कर्मणोपि करणत्वविवक्षया । अस्ति प्रकाशने, देवदत्ताय शपते । कथयतीत्यर्थः । तत्र स्वरितेत्त्वात् सिद्धेऽकर्त्रभिप्रायार्थमिदम् । तदपि प्रकाशनार्थ एव । तदाह—**उपलम्भनं प्रकाशनमिति ।** यद्येवं शपतेर्ण्यन्तजानात्यर्थत्वेन द्विकर्मकत्वे देवदत्तं शपत इत्यापत्तिरत आह—**श्लाघह्नुङिति ॥** ननु शापयितुमिष्टस्य संप्रदानत्वम् । शापयितुमिष्टं चाणौ कर्मैव न तु णौ कर्मेत्याशङ्क्याह—**केचिदिति ।** प्रधानभूतप्रत्ययार्थकर्मण एव ग्राह्यत्वादिति भावः ॥ **य इति ।** प्रथमोपस्थितत्वात्प्रकृत्यर्थकर्मैव ग्राह्यमिति भावः ॥ प्रकृते देवदत्तस्तादृश एवेत्याशयः ॥ अत्राद्यं मतं न युक्तं तथा हि सति शाप्यमान इत्येव सिद्धे मनुपादानवैयर्थ्यापत्तेः ॥ '**मख्यः शपामि यदि किंचिदपि स्मरामी**त्यादौ तु शपथार्थकत्वान्नात्मनेपदम् ॥ काशिकादौ तूप**लम्भनं शपथ** इति व्याख्यातं, तच्चिन्त्यम् । उपलम्भनशब्दस्य योगेन प्रकाशनार्थकत्वात् । शपथे रूढिकल्पने न मानम् ।

अत एव हरिणैतदुदाहरणे शपिर्द्विकर्मक इति व्याख्यातम् ॥ २१ ॥

(१३७ आत्मनेपदनियमसूत्रम् । १ । ३ । २ आ. ८ सू.)

१६९ समवप्रविभ्यः स्थः ॥ १ । ३।२२॥

(९१९ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ आङः स्थः प्रतिज्ञाने ॥ * ॥

(भाष्यम्) आङः स्थः प्रतिज्ञान इति वक्तव्यम् । अस्ति सकारमातिष्ठते । आगमौ गुणवृद्धी आतिष्ठते । विकारौ गुणवृद्धी आतिष्ठते ॥ समव ॥२२॥

(उद्द्योतः) समवप्र ॥ २२ ॥ अस्तिमिति । केचित्सकारमात्रं धातुं पठित्वा विति सार्वधातुकेऽडागमौ गुणवृद्धिरूपावागमावित्याहुः ॥ **विकाराविति ।** तस्यानेऽस्तिमास्ति चेत्यर्थः ॥ २२ ॥

(१३८ आत्मनेपदनियमसूत्रम् । १ । ३ । २ आ. ९ सू.)

१७१ उदोनूर्ध्वकर्मणि ॥ २४ ॥

(९२० आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ उद ईहायाम् ॥ * ॥

(भाष्यम्) उद ईहायामिति वक्तव्यम् । इह मा भूत्—उत्तिष्ठति सेनेति ॥ उदः ॥ २४ ॥

(प्रदीपः) उदोनू ॥ २४॥ उद ईहायामिति । ईहा विशिष्टा चेष्टा कायपरिस्पन्दात्मिका गृह्यते ॥ **उत्तिष्ठति सेनेति ।** उत्पद्यते जायते सेनेत्यर्थः ॥ २४ ॥

(उद्द्योतः) उदोऽनूर्ध्व ॥ २४ ॥ सर्वस्यापि धात्वर्थस्येहानुविद्धत्वाद्विशिष्योपादानं व्यर्थमत आह—**ईहेति ॥** प्रत्युदाहरणे तादृशव्यापाराभावं दर्शयति—**उत्पद्यत इति** ॥ २४ ॥

(१३९आत्मनेपदनियमसूत्रम् ।१। ३ । २ । आ. १० सू.)

१७२ उपान्मन्त्रकरणे ॥ २५ ॥

(९२१ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ उपाद्देवपूजासंगतकरणयोः ॥ * ॥

(भाष्यम्) उपाद्देवपूजासंगतकरणयोरिति वक्तव्यम् । आदित्यमुपतिष्ठते । चन्द्रमसमुपतिष्ठते॥ संगतकरणे—रथिकानुपतिष्ठते । अश्वारोहानुपतिष्ठन्ते ॥

बहूनामप्यचित्तानामेको भवति चित्तवान् ।
पश्य वानरसैन्येस्मिन्यदर्कमुपतिष्ठते ॥ १ ॥
मैवं मंस्थाः सचित्तोयमेषोपि हि यथा वयम् ।
एतदप्यस्य कापेयं यदर्कमुपतिष्ठति ॥ २ ॥

(प्रदीपः) उपान्मन्त्र ॥२५॥ उपाद्देवपूजेति। अमन्त्रकरणार्थमिदम् ॥ अर्कमुपतिष्ठते इति। देवपूजां मत्वात्मनेपदं कृतम् ॥ चापलमेतन्न पूजनमिति न कृतमपरत्र ॥

(उद्द्योतः) उपान्मन्त्र ॥ २५ ॥ ननु देवपूजाया मन्त्रकरणकत्वात्सूत्रेणैव सिद्धमत आह—अमन्त्रेति। अमन्त्रकरणकेऽर्थे वर्त्तमानात्स इत्यर्थ इति भावः ॥

(न्यासान्तरप्रदर्शकभाष्यम्)

अपर आह—

(वार्तिकन्यासान्तरम्)

॥ * ॥ उपाद्देवपूजासंगतकरणमित्रकरणपथिषु ॥ * ॥

(भाष्यम्) उपाद्देवपूजासंगतकरणमित्रकरणपथिष्विति वक्तव्यम् ॥ देवपूजासंगतकरणयोरुदाहृतम्। मित्रकरणे—रथिकानुपतिष्ठते, अश्वारोहानुपतिष्ठते। पथिषु—अयं पन्थाः स्रुघ्नमुपतिष्ठते, अयं पन्थाः साकेतमुपतिष्ठते ॥

(प्रदीपः) अपर आहेति। सङ्गतकरणमुपश्लेषमात्रं मित्रकरणं त्वनुपश्लिष्टस्यापि मैत्रीसम्बन्धः ॥ अयं पन्थाः स्रुघ्नमुपतिष्ठत इति। स्रुघ्नं प्राप्नोतीत्यर्थः ॥

(उद्द्योतः) मैत्रीसम्बन्धः प्रीतिरूपः ॥ ननु पथ्यपि सङ्गतकरणमस्तीति पृथग् ग्रहणं व्यर्थमत आह—प्राप्नोतीति। प्राप्यप्रापकव्यापारपूर्वकसंबन्धो हि तत्। न चेह तदस्ति। यतः पथः स्रुघ्नस्य च बुद्धिकल्पितप्राप्तिक्रियापेक्षं कारकत्वम्, न तु वस्तुत इति भावः ॥

(९२२ आक्षेपवार्तिकम् ॥ २ ॥)

॥ * ॥ वा लिप्सायाम् ॥ * ॥

(भाष्यम्) वा लिप्सायामिति वक्तव्यम्। भिक्षुको ब्राह्मणकुलमुपतिष्ठते। भिक्षुको ब्राह्मणकुलमुपतिष्ठति ॥ उपान्मन्त्रक ॥ २५ ॥

(प्रदीपः) भिक्षुक इति। लिप्सया हेतुभूतया ब्राह्मणकुलमुपगच्छतीत्यर्थः ॥ २५ ॥

(उद्द्योतः) लिप्सयेति। लिप्साकरणके उपगमने गमेर्वृत्तिरिति भावः ॥ २५ ॥

(१४० आत्मनेपदनियमसूत्रम् ।१।३।२ आ. ११ सू.)

१७४ उद्विभ्यां तपः ॥ १ । ३ । २७ ॥

(भाष्यम्) अकर्मकादित्येव। [इह मा भूत्—] उत्तपति सुवर्णं सुवर्णकारः ॥

(प्रदीपः) उद्विभ्याम् ॥२७॥ भासने वर्तमानस्तपिरुद्विपूर्वोऽकर्मकः ॥

(उद्द्योतः) उद्विभ्याम् ॥ २७ ॥ उत्तपति सुवर्णमित्यादिप्रयोगादकर्मकत्वं तपेर्विशेषणं न सम्भवतीत्यत आह—भासने इति। उत्तपते वितपते सूर्य इत्युदाहरणम्। भासत इत्यर्थः ॥

(९२३ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ स्वाङ्गकर्मकाच्च ॥ * ॥

(भाष्यम्) स्वाङ्गकर्मकाच्चेति वक्तव्यम्। उत्तपते पाणी, वितपते पाणी। उत्तपते पृष्ठम्, वितपते पृष्ठम् ॥

(प्रदीपः) स्वाङ्गमिहोत्तरत्र च पूर्वसूत्रवत्स्वमङ्गं गृह्यत इतीह न भवति—देवदत्तो यज्ञदत्तस्य पाणिमुत्तपतीति ॥

(उद्द्योतः) स्वमङ्गमिति। न स्वद्रवं मूर्त्तिमदिति भावः ॥

(आक्षेपभाष्यम्)

अथोद्विभ्यामित्यत्र किं प्रत्युदाह्रियते?।

(प्रदीपः) अथेति। किमयं विधिः, अथ नियम इत्यभिप्रायेण प्रश्नः ॥

(उद्द्योतः) प्रत्युदाहरणविशेषप्रश्ने तात्पर्यमाह—किमयमिति। यदि कर्मकर्तृत्वं विनाप्यकर्मकत्वमुत्तपेस्तदा विध्यर्थम्। अथ कर्मकर्तर्येवाकर्मकत्वं ततो नियमार्थमिति भावः ॥

(नियमपक्षवादिसमाधानभाष्यम्)

निष्टप्यते इति ॥

(प्रदीपः) उद्विभ्यां तप आत्मनेपदमेव न यगादीति नियमोनेन क्रियत इत्याह—निष्टप्यत इति ॥

(उद्द्योतः) नियमपक्षे यगादिनिवृत्तिः फलमिति यगादिमत्प्रत्युदाहार्यमित्याह—उद्विभ्यामिति ॥

(विधिपक्षवाद्याक्षेपभाष्यम्)

किं पुनः कारणमात्मनेपदमेवोदाह्रियते, न पुनः परस्मैपदं प्रत्युदाहार्यं स्यात्?।

(प्रदीपः) विधिनियमसंभवे विधिर्बलवानिति मत्वाह—किं पुनरिति ॥

(नियमपक्षवादिसमाधानभाष्यम्)

तपिरयमकर्मकः ॥ अकर्मकाश्चापि सोपसर्गाः सकर्मका भवन्ति। न चान्तरेण कर्मकर्तारं सकर्मका अकर्मका भवन्ति ॥

(प्रदीपः) विधिर्न संभवतीति मत्वाह—तपिरिति। भासते दीप्यत इत्यत्रार्थेऽकर्मक इत्यर्थः ॥ अकर्मकाश्चेति। अनेकार्थत्वाद्धातूनामन्तर्भावितण्यर्थत्वादिति भावः। ततश्च तापने वर्तमानस्तपिः सकर्मकः। पुनः प्रयोजकव्यापाराविवक्षायां कर्तुः कर्मवद्भावात्सिद्धमात्मनेपदमिति पुनर्विधानं नियमार्थं संपद्यत इत्यन्यत्राप्यात्मनेपदं भवत्येव ॥

(उद्द्योतः) भाष्ये तपिरयमकर्मक इति। तपिरयमकर्मकः सूत्रे गृहीतोऽकर्मकादित्यधिकारादित्यर्थः ॥ अकर्मकत्वं चास्य

कर्मकर्तर्यवेति न परस्मैपदं प्रत्युदाहर्तुं शक्यमिति भावः ॥ तदाह—भासत इति । इत्यत्रार्थे शुद्धस्तपिरकर्मकः, उदादिपूर्वस्त्वन्तर्भावितण्यर्थत्वात् सकर्मक एव । तस्य च न कर्मकर्तृत्वं विनाऽकर्मकत्वमिति विधित्वासम्भव इति भावः ॥ अनेकार्थत्वादिति । उद्विरूपोपसर्गस्त्वन्तर्भावितण्यर्थत्वस्यैव द्योतक इति भावः ॥ तपिः सकर्मक इति । उदादिपूर्वकः सकर्मक एवेति भावः ॥ अन्यत्रापीति । उद्विभ्यामन्यत्रापीत्यर्थः ॥ अत्रापीतिपाठे निष्प्यत इत्यत्रापीत्यर्थः ॥

(समाधानबाधकविधिपक्षवादिभाष्यम्)

यदुच्यते—न चान्तरेण कर्मकर्तारं सकर्मका अकर्मका भवन्तीति ॥ अन्तरेणापि कर्मकर्तारं सकर्मका अकर्मका भवन्ति । तद्यथा—नदी वहती- त्यकर्मकः, भारं वहतीति सकर्मकः । तस्मान्निष्टपतीति प्रत्युदाहार्यम् ॥ २७ ॥ उद्विभ्याम् ॥

(प्रदीपः) इदानीं विधिपक्षवाद्याह—अन्तरेणापीति । तदेवं ज्वलनवृत्तिस्तपिरकर्मकः । संतापने विलापने च सकर्मकः ॥ कर्मकर्तरि तु यक्चिणोः प्रतिषेधे णिश्रन्थिग्रन्थीति वचनेन यक्चिणौ प्रतिषिद्धौ ॥ २७ ॥

(उद्द्योतः) इदानीमिति । अकर्मकाणामुपसर्गसंबन्धेपि प्रवृत्त्यत इति वत्सकर्मकत्वनियमाभावाद्विधिरेव सिद्धान्त इत्याशयः ॥ नदी वहतीत्यस्य स्यन्दत इत्यर्थः ॥ तदेवमिति । उपसर्गसंबन्धेपीत्यर्थः । एवं च कर्मकर्तारं विनाप्युदाहरणसम्भव इति भावः ॥ तर्हि कर्मकर्तर्युत्तपत इत्यस्यासिद्धिः? । नेष्टः, प्रकारान्तरेण तद्यावृत्तेरित्याशयेनाह—कर्मकर्तरि त्विति । आत्मनेपदविधायकर्मकाद्यक्चिणोः प्रतिषेधेनोपसर्गान्तरसंबन्धे तत्र यक्चिणौ भवत एवेति बोध्यम् ॥ २७ ॥

(१४१ आत्मनेपदनियमसूत्रम् ।१ । ३ । २ आ. १२ सू.)

१७५ आङो यमहनः ॥ १।३।२८ ॥

(भाष्यम्) अकर्मकादित्येव । [इह मा भूत्—] आयच्छति रज्जुं कूपात् । आहन्ति वृषलं पादेन ॥

(उद्द्योतः) आङो यम ॥ २८ ॥ भाष्ये आयच्छतीति । आकर्षतीत्यर्थः ॥ २८ ॥

(९२४ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ स्वाङ्गकर्मकाच्च ॥ * ॥

(भाष्यम्) स्वाङ्गकर्मकाच्चेति वक्तव्यम् । आयच्छते पाणी । आहते उदरमिति ॥ आङो यमहनः ॥ २८ ॥

(१४२ आत्मनेपदनियमसूत्रम् १ । ३ । २ आ. १३ सू.)

१७६ समो गम्यृच्छिभ्याम् ॥१।३।२९॥

(९२५ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ समो गमादिषु विदिप्रच्छिस्वरतीनामुपसंख्यानम् ॥ * ॥

(भाष्यम्) समो गमादिषु विदिप्रच्छिस्वरतीनामुपसंख्यानं कर्तव्यम् । संविते । संपृच्छते । संस्वरते ।

(प्रदीपः) समः ॥ २९ ॥ समो गम्यृच्छिभ्यामित्येतावत्सूत्रमिति वार्तिकमारब्धम् ॥

(उद्द्योतः) समो गम्यृ ॥ २९ ॥ विदादीनामपि सूत्र एव वृत्तिकारैः पाठाद्वार्तिकं व्यर्थमत आह—समो गमिति । प्रामादिकः स पाठ इति भावः ॥ भाष्ये—गमादिष्विति बहुवचनं प्रयोगबाहुल्याभिप्रायेण ॥

(९२६ आक्षेपवार्तिकम् ॥ २ ॥)

॥ * ॥ अर्तिश्रुदृशिभ्यश्च ॥ * ॥

(भाष्यम्) अर्तिश्रुदृशिभ्यश्चेति वक्तव्यम् । अर्ति—मा समृत । मा समृषाताम् । मा समृषत । अर्ति ॥ श्रु—संशृणुते । दृशि—संपश्यते ॥

(उद्द्योतः) भाष्ये—मासमृतेति । अर्तिर्धौ लुप्तविकरणशास्तिसाहचर्यात् जुहोत्यादेरेव ग्रहणमिति भ्वादेरिदम् । तस्य तु मा समरतेत्यादि ॥ परस्मैपदेष्विति त्वर्तिर्धा न संबध्यते योगविभागसामर्थ्यादिति वृत्तिः ॥ भाष्योदाहरणबलात्संबध्यते एव । योगविभागो वैचित्र्यार्थः ॥ यद्वा वार्तिके श्रुदृशिसाहचर्याद् भ्वादेरेव ग्रहणमितीयतैतन्नात्मनेपदमित्यन्ये ॥

(९२७ आक्षेपवार्तिकम् ॥ ३ ॥)

॥ * ॥ उपसर्गादस्यत्यूह्योर्वावचनम् ॥ * ॥

(भाष्यम्) उपसर्गादस्यत्यूह्योर्वेति वक्तव्यम् । निरस्यति निरस्यते । समूहति । समूहते ॥ समो ॥ २९ ॥

(प्रदीपः) उपसर्गादिति । अत्राकर्मकादिति न संबध्यते ॥ २९ ॥

(उद्द्योतः) निरस्यतिसमूहत्योः सकर्मकत्वादाह—अत्रेति ॥ २९ ॥

(१४३ आत्मनेपदनियमसूत्रम् ।१। ३। २ आ. १४ सू.)

१७७ आङ उद्गमने ॥ ४० ॥

(९२८ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ ज्योतिषामुद्गमने ॥ * ॥

(भाष्यम्) ज्योतिरुद्गमने इति वक्तव्यम् । इह

मा भूत्—आक्रामति धूमो हर्म्यतलादिति ॥ आङ ॥ ४० ॥

(प्रदीपः) आङः ॥४०॥ ज्योतिषामिति । उद्गमने वर्तमानोऽकर्मकः क्रमिः । इह तु नभः समाक्रामतीति न भवत्यात्मनेपदम् । अत्र हि क्रमिर्व्याप्तौ वर्तते न तूद्गमने ॥ ४० ॥

(उद्योतः) आङ उद्ग ॥ ४० ॥ ननु ज्योतिषामुद्गमने इत्यस्य ज्योतिःसंबन्ध्युद्गमने इत्यर्थः । एवं च पक्षी सूर्यमाक्रामतीत्यत्रापि प्रसङ्गः । यद्वा कर्मणि कर्तरि वा षष्ठीत्यत्र विनिगमनाविरहात्तत्रापि प्रवृत्तिः । न चोभयप्राप्तावितिति कर्मण्येवैषा षष्ठी, तथा सति ज्योतिरुद्गमन इति भाष्यकृत्कृतसमस्तप्रयोगानुपपत्तिरित्युभयोपादान एव तत्प्रवृत्तिरत आह—उद्गमने इति ॥ प्रत्युदाहरणभाष्ये हर्म्यतलादित्येव पाठः सांप्रदायिक इति भावः ॥ एवं चोद्गमनमत्रोदय एवेति बोध्यम् ॥ ४० ॥

(१४४ आत्मनेपदनियमसूत्रम् । १ । ३ ।२ आ. १५ सू.)

१९५ व्यक्तवाचां समुच्चारणे ॥ ४८ ॥

(व्यक्तवाक्पदार्थनिर्णयाधिकरणम्)

(आक्षेपभाष्यम्)

व्यक्तवाचामिति किमर्थम्? ॥

(समाधानभाष्यम्)

'वरतनु संप्रवदन्ति कुक्कुटाः ॥'

(समाधानबाधकभाष्यम्)

व्यक्तवाचामित्युच्यमानेप्यत्र प्राप्नोति । एतेपि हि व्यक्तवाचः ॥ आतश्च व्यक्तवाचः । कुक्कुटेनोदिते उच्यते—कुक्कुटो वदतीति ॥

(समाधानसाधकभाष्यम्)

एवं तर्हि 'व्यक्तवाचाम्' इत्युच्यते । सर्व एव हि व्यक्तवाचः । तत्र प्रकर्षगतिर्विज्ञास्यते—साधीयो ये व्यक्तवाच इति ॥ के च साधीयः? । येषां वाच्यकारादयो वर्णाः व्यज्यन्ते ॥ न चैतेषां वाच्यकारादयो वर्णा व्यज्यन्ते ॥

(प्रदीपः) व्यक्तवाचाम् ॥४८॥ सर्व एवेति । ये वदत्यर्थस्य कर्तारः । वद व्यक्तायां वाचीति पाठादिति भावः ॥

(उद्योतः) व्यक्तवाचां ॥ ४८ ॥ मनुष्यादिव्यतिरिक्तानां व्यक्तवाक्त्वाभावात्सर्वे व्यक्तवाच इत्यसंगतमत आह—ये इति ॥ भाष्ये येषां वाच्यकारादय इति । येषां वाचि वैखरीरूपायामकारादयो वर्णा व्यज्यन्ते व्यक्ता भवन्तीत्यर्थः ॥

(समाधानबाधकभाष्यम्)

एतेषामपि वाच्यकारादयो वर्णा व्यज्यन्ते ॥ आतश्च व्यज्यन्ते । एवं ह्याहुः कुक्कुटाः कुक्कुडिति ॥

(उद्योतः) कुक्कुटाः कुक्कुडिति भाष्यस्य वदन्तीति शेषः । एवं जना आहुरित्यन्वयः ॥

(समाधानसाधकभाष्यम्)

नैवं ते आहुः । अनुकरणमेतत्तेषाम् ॥

अथ वा नैवं विज्ञायते—व्यक्ता वाग्येषां त इमे व्यक्तवाच इति ॥ कथं तर्हि? ॥ व्यक्ता वाचि वर्णा येषां त इमे व्यक्तवाच इति ॥ व्यक्तवाचां ॥ ४८ ॥

(प्रदीपः) अथ वेति । विनापि प्रकर्षगत्या व्यधिकरणपदबहुव्रीह्याश्रयणान्मनुष्या एव गृह्यन्ते ॥ व्यक्ता वाचीति । वाचि अकारादयो वर्णा येषां व्यक्तास्तेषामित्यर्थः । शुकसारिकादीनां न सर्ववर्णविषयं स्वाभाविकं व्यक्तवाक्त्वमपि तु पुरुषप्रयत्नवशेन कतिपयवर्णविषयमिति तत्रात्मनेपदाभावः॥४८

(उद्योतः) वाचि शब्दे ॥ निष्ठेति व्यक्तशब्दस्य पूर्वनिपातः ॥ ४८ ॥

(१४५ आत्मनेपदनियमसूत्रम् ॥ १।३ । २ आ. १६ सू.)

१९८ अवाद्ग्रः ॥ ५१ ॥

(९२९ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ अवाद्ग्रो गिरतेः ॥ * ॥

(भाष्यम्) अवाद्ग्र इत्यत्र गिरतेरिति वक्तव्यम् । गृणातेर्मा भूत् ॥

(तृतीयाक्षेपभाष्यम्)

तत्तर्हि वक्तव्यम् ।

(९३० आक्षेपबाधकवार्तिकम् ॥ २ ॥)

[॥ * ॥ न वा प्रयोगाभावात् ॥ * ॥]

(भाष्यम्) न [वा] वक्तव्यम् । प्रयोगाभावात् । 'अवाद्ग्र' इत्युच्यते । न चावपूर्वस्य गृणातेः प्रयोगोस्ति ॥ अवाद्ग्रः ॥ ५१ ॥

(प्रदीपः) अवाद्ग्रः ॥ ५१ ॥ न चावपूर्वस्येति । नियतविषयत्वात्केषांचित्क्रियाविशेषणानाम् । यथोर्यादयः कृभ्वस्तिविषया एवेति भावः ॥ ५१ ॥

(उद्योतः) अवाद्ग्रः ॥ ५१ ॥ अनुगृणातीतिवद् अवगृणातीति प्रयोगं को वारयेदत आह—नियतेति ॥ क्रियाविशेषणानां, तद्विशेषणार्थद्योतकानाम् ॥ ५१ ॥

(१४६ आत्मनेपदनियमसूत्रम् । १ ३ । २ आ. १७ सू.)

२०१ समस्तृतीयायुक्तात् ॥ ५४ ॥

(आक्षेपभाष्यम्)

तृतीयायुक्तादिति किमर्थम्? ॥

(प्रदीपः) समः ॥५४॥ धातोस्तृतीयायोगासंभवात्तदर्थेन योगे भाव्यमात्मनेपदेन । स च सर्वत्र चरत्यर्थे संभवतीत्यभिप्रायेणाह—तृतीयायुक्तादिति किमर्थमिति ॥

(उद्द्योतः) समस्तृ ॥ ५४ ॥ तृतीयायोगाभावे आत्मनेपदनिवृत्त्या तस्य चारितार्थ्यात् प्रश्नानुपपत्तिमाशङ्क्याह—धातोरिति ॥ तदर्थेन करणेन ॥

(समाधानभाष्यम्)

'उभौ लोकौ संचरसीमं चामुं च देवल' ॥

(समाधानबाधकभाष्यम्)

तृतीयायुक्तादित्युच्यमानेप्यत्र प्राप्नोति । अत्रापि हि तृतीयया योग इति ॥

(समाधानसाधकभाष्यम्)

एवं तर्हि तृतीयायुक्तादित्युच्यते । सर्वत्र च तृतीयया योगः । तत्र प्रकर्षगतिर्विज्ञास्यते—साधीयो यत्र तृतीया योग इति । क च साधीयः? । यत्र तृतीया श्रूयते ॥ समस्तृ० ॥ ५४ ॥

(प्रदीपः) सर्वत्रेति । केचित्सर्वक्रियापेक्षमेतदुक्तमिति मन्यन्ते । यथा असिना छिनत्ति असिस्तैक्ष्ण्येन च्छिनत्ति तैक्ष्ण्यमात्मना छिनत्तीति । यत्रापि करणाभिधायि पदं न श्रूयते तत्रापि केनचित्करणेन भाव्यमन्ततः एकस्यैव पदार्थस्य भेदविवक्षायामात्मा करणम् ॥ अन्ये तु चरतिक्रियापेक्षमेवमुक्तमित्याहुः । नहि संचरणं करणेन विना संभवति ॥ यत्रेति । तत्र ह्यन्तरङ्गा करणप्रतीतिः । अन्यत्र तु करणस्य परिकल्प्यत्वाद्बहिरङ्गा ॥ ५४ ॥

(उद्द्योतः) केचिदिति । सर्वत्रेति सामान्योक्तेरिति तद्भावः ॥ यत्रापीति । अस्ति शेत इत्यादौ ॥ अन्ये त्विति । प्रकरणादिति भावः ॥ अन्तरङ्गत्वं शैघ्र्यमेव ॥ ५४ ॥

(१४७ आत्मनेपदनियमसूत्रम् ॥ १ । ३ । २ आ. १८ सू०)

२०२ दाणश्च सा चेच्चतुर्थ्यर्थे ॥ ५५ ॥

(तृतीयोपपादनाधिकरणम्)

(आक्षेपभाष्यम्)

'सा चेत्तृतीया चतुर्थ्यर्थे' इत्युच्यते । कथं नाम तृतीया चतुर्थ्यर्थे स्यात्? ॥

(समाधानभाष्यम्)

एवंतर्हि—

(९३१ सिद्धान्तवार्तिकम् ॥ १ ॥)

[॥ * ॥ अशिष्टव्यवहारे तु तृतीया च विधीयते ॥ * ॥]

(भाष्यम्) [किं च? ॥ आत्मनेपदं च ।] अशिष्टव्यवहारेनेन तृतीया च विधीयत आत्मनेपदं च । दास्या संप्रयच्छते वृषल्या संप्रयच्छते । यः शिष्टव्यवहारः ब्राह्मणीभ्यः संप्रयच्छतीत्येव तत्र भवितव्यम् ॥

(प्रदीपः) दाणश्च ॥ ५५ ॥ अशिष्टव्यवहारइति । अशिष्टानां संकीर्णाचाराणां यो व्यवहारस्तस्मिन्नित्यर्थः । तत्र चेच्छब्दं चार्थे व्याचक्षाणा अनेनैवोभयं संगृहीतमित्याहुः ॥

(उद्द्योतः) दाणश्च ॥ ५५ ॥ अशिष्टोऽविहितो व्यवहार इत्यर्थे दास्यै संयच्छति वास इत्यत्रापि स्यादत आह—अशिष्टानामिति । अशिष्टशब्दः प्रतिषिद्धकर्तृषु रूढ इति भावः ॥ [भाष्ये—अनेनेति नास्तीति कैयटस्वरसः ॥]

(पूर्वपक्षिप्रत्याख्यानभाष्यम्)

यद्येवं नार्थोनेन ॥

(उद्द्योतः) अनेनेति । अशिष्टव्यवहार इति तु कर्तव्यमेव ॥

(आक्षेपभाष्यम्)

केनेदानीं तृतीया भविष्यति, आत्मनेपदं च? ॥

(९३२ पूर्वपक्षिसमाधानवार्तिकम् ॥ २ ॥)

॥ * ॥ सहयुक्ते तृतीया स्याद् व्यतिहारे तङो विधिः ॥ * ॥

(भाष्यम्) "सहयुक्तेऽप्रधाने" इत्येव तृतीया भविष्यति, "कर्तरि कर्मव्यतिहारे" इत्यात्मनेपदम् ॥ दाणश्च ॥ ५५ ॥

(प्रदीपः) सहयुक्तइति । दास्यै विश्राण्य तया सह उपभुङ्क्ते इत्ययं वाक्यार्थः ॥ ५५ ॥

(उद्द्योतः) दास्यै इति । दासमभिलषितं धूर्तः करोति दासी च धूर्ताभिलषितमिति व्यतीहारसिद्धिः । दानपूर्वकोपभोगे च संप्रयच्छतिरिति भावः ॥ अत्र वदन्ति—यद्यनेनेत्यादिपूर्वपक्ष्युक्तिरियुक्तिप्रत्युक्तिस्वारस्येन प्रतीयते । तया सहोपभुङ्क्ते इत्येतन्मात्रेण व्यतीहाराप्रतीतेः । विश्राणनमादाय तु न सः । अन्ययोरेकजातीयक्रियाणामन्येन करणं हि सः । तस्यै विश्राण्य तामुपभुङ्क्ते इत्यर्थे कर्मव्यतीहाराप्रतीतावप्यशिष्टत्वप्रतीत्या तत्रेष्टात्मनेपदासिद्धेश्च, उपपदविभक्तेरितिन्यायेन विश्राणननिरूपितचतुर्थ्या एवापत्तेश्च, धातोर्व्यतीहारे वृत्तावपि कर्त्तरीतिसूत्रे तद्वात्वर्थकर्तृमात्रे तङो विधानौचित्येन तिङोक्तत्वात्तेनैव न्यायेन प्रथमापत्तेश्च । अत एव क्रियायोगे कर्त्तरीत्येव तृतीयायां सिद्धायामक्रियायोगार्थं सूत्रमिति तेन सहेतिसूत्रे भाष्यकृद्वक्ष्यतीत्यलम् ॥ ५५ ॥

(१२७ आत्मनेपदनियमसूत्रम् ॥ १ । ३ । २ आ. १९ सू.)

२०३ उपाद्यमः स्वकरणे ॥ ५६ ॥

(स्वकरणशब्दार्थनिरूपणाधिकरणम्)

(आक्षेपभाष्यम्)

इह कस्मान्न भवति । स्वं शाटकान्तमुपयच्छति—इति ? ॥

(प्रदीपः) उपाद्यमः ॥५६॥ स्वस्य स्वत्वेन स्थितस्य ग्रहणादिकं करणं स्वकरणं गृह्यते इति मत्वा प्रश्नः—इहेति ॥

(उद्द्योतः) उपाद्यमः ॥ ५६ ॥ स्वस्य सतः शाटकान्तस्याभूतप्रादुर्भावलक्षणकरणायोगात् प्रश्नानुपपत्तिरत आह—स्वस्येति । करणं क्रिया ग्रहणादिरूपेत्यर्थः ॥

(समाधानभाष्यम्)

अस्वं यदा स्वं करोति तदा भवितव्यम् ॥

(प्रदीपः) अस्वमिति । अन्तरङ्गत्वान्निष्पादनलक्षणोत्र करोत्यर्थो गृह्यते ॥

(उद्द्योतः) अन्तरङ्गत्वादिति । निष्पन्नस्य हि ग्रहणं, निष्पत्तिश्च निष्पादनाधीनेत्यन्तरङ्गता । किं चायमर्थः प्रकरणाद्यनपेक्षः । अर्थान्तरे तु तदपेक्षेत्यन्तरङ्गत्वम् ।

(आक्षेपभाष्यम्)

यद्येवं स्वीकरणमिति प्राप्नोति ।

(समाधानभाष्यम्)

विचित्रास्तद्धितवृत्तयः । नातस्तद्धित उत्पद्यते ॥ उपाद्यमः स्वकरणे ॥ ५६ ॥

(प्रदीपः) नात इति । च्वेर्विकल्पेन विधानादिति केचिदाहुः । प्रकृतेरविवक्षितत्वात्कार्यमात्रविवक्षायां नास्ति च्विरित्यपरे ॥ ५६ ॥

(उद्द्योतः) केचिदाहुरिति । तदा हि अस्वं स्वं करोतीतिवाक्येन भवितव्यमित्यरुचिः ॥ प्रकृतेरिति । स्वकरण इत्यस्य स्वत्ववतो निष्पादने इत्यर्थ इति भावः । च्विस्तु न वास्तवे तथाभवने, किं त्वारोपित एव स्वभावादिति तात्पर्यम् । इदमेव वैचित्र्यम् ॥ ५६ ॥

(१४९ आत्मनेपदनियमबाधकसूत्रम् १।३।२ आ.२० सू.)

२०५ नानोर्ज्ञः १।३।५८ ॥

(प्रतिषेधविषयनिर्णयाधिकरणम्)

(९३३ आक्षेपवार्तिकम् ॥ १ ॥)

॥*॥ अनोर्ज्ञः प्रतिषेधे सकर्मकवचनम् ॥*॥

(भाष्यम्) अनोर्ज्ञः प्रतिषेधे सकर्मकग्रहणं कर्तव्यम् । इह मा भूत्—'औषधस्यानुजिज्ञासते' इति ।

(प्रदीपः) नानोर्ज्ञः ॥५८॥ औषधस्येति । औषधेन प्रवर्तितुमिच्छतीत्यर्थः ।

(उद्द्योतः) नानोर्ज्ञः ॥ ५८ ॥ औषधेनेति । ज्ञो विदर्थस्येति करणे शेषषष्ठीति भावः ॥

(९३४ समाधानवार्तिकम् ॥ २ ॥)

॥ * ॥ न वाऽकर्मकस्योत्तरेण विधानात् ॥ * ॥

(व्याख्याभाष्यम्)

न वा कर्तव्यम् । किं कारणम् ? । अकर्मकस्योत्तरेण विधानात् । अकर्मकाज्जानातेरुत्तरेण योगे नात्मनेपदं विधीयते "पूर्ववत्सनः" इति ॥

(प्रदीपः) न वेति । पूर्वेण सकर्मकाज्जानातेः सन्नन्तादात्मनेपदं विधीयते । अकर्मकात्तु परत्वात्पूर्ववत्सन इत्यनेन ॥ ५८ ॥

(उद्द्योतः) भाष्ये—अकर्मकाज्जानातेरित्यस्य सनन्तादिति शेषः ॥ पूर्ववत्सन इत्यनेनेति । अकर्मकाच्चेति सूत्रेण केवलाज्जानातेस्तद्विधानादिति भावः ॥ ५८ ॥

(९३५ समाधानान्तरवार्तिकम् ॥ ३ ॥)

॥ * ॥ प्रतिषेधः पूर्वस्य च ॥ * ॥

(व्याख्याभाष्यम्)

पूर्वस्य चायं प्रतिषेधः । स च सकर्मकार्थ आरम्भः ॥

(आक्षेपभाष्यम्)

कथं पुनर्ज्ञायते—पूर्वस्यायं प्रतिषेध इति ? ॥

(समाधानभाष्यम्)

अनन्तरस्य विधिर्वा भवति प्रतिषेधो वेति ॥

(आक्षेपभाष्यम्)

कथं पुनर्ज्ञायते—सकर्मकार्थ आरम्भ इति ? ।

(समाधानभाष्यम्)

अकर्मकाज्जानातेः सन आत्मनेपदवचने प्रयोजनं नास्तीति कृत्वा सकर्मकार्थो विज्ञायते ॥ नानोर्ज्ञः ॥ ५८ ॥

(१५० आत्मनेपदनियमसूत्रम् १ । ३ । २ आ. २१ सू.)

२०७ शदेः शितः १।३।६० ॥

(अनुपपत्तिपरिहाराधिकरणम्)

(९३६ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ शदेः शितः परस्मैपदाश्रयत्वादात्मनेपदाभावः ॥ * ॥

(व्याख्याभाष्यम्)

शदेः शितः परस्मैपदाश्रयत्वादात्मनेपदस्या-

भावः । शीयते शीयेते शीयन्ते ॥

(प्रदीपः) शदेः शितः ॥६०॥ शदेरिति । शद्विकरणोत्पत्तेः पूर्वमात्मनेपदनिमित्ताभावाच्छेषत्वात्परस्मैपदेन भाव्यम् । तत्र कृते शित्प्रत्यये नानेन विहितं परस्मैपदं निवर्तयितुं शक्यत इत्यप्रतिपादकत्वलक्षणमप्रामाण्यमस्य सूत्रस्य प्राप्तम् ॥

(उद्द्योतः) शदेः शितः ॥ ६० ॥ शदेः परो यः शित्प्रत्ययस्ततः परस्य लस्य स्थाने आत्मनेपदमेवेति मत्वा वार्त्तिकावतार इत्याशयेनाह—शिदिति ॥ ननु विकरणात्पूर्वमात्मनेपदनिमित्ताभावेपि लादेशवाक्येन सामान्यतः प्राप्तं सार्वधातुकमाश्रित्य सार्वधातुकविषये विधीयमाने विकरणे कृते नियमः स्यादत आह—शेषत्वादिति । अनुदात्तङित्तो भावकर्मणोरितिसूत्रद्वयापेक्षशेषस्यैव तत्र ग्रहणादित्यर्थः । विकरणेभ्यो नियमस्य बलवत्त्वादिति भावः ॥ निवर्त्तयितुं शक्यते इति । भुक्तवम्तं प्रतीतिन्यायेनेति भावः ॥ शास्त्रान्तरेण कृतनियमस्य निवृत्तिरशक्या, तेन निवर्तितत्वां प्रतिपत्तिश्चाशक्येति तात्पर्यम्

(प्रत्याक्षेपभाष्यम्)

किं च भोः शदेः शित्परस्मैपदेष्वित्युच्यते ? ॥

(प्रदीपः) किं च भो इति । सार्वधातुकसंशब्दनेन शितो विधानं न परस्मैपदसंशब्दनेन ॥

(प्रत्याक्षेपबाधकभाष्यम्)

न खलु 'परस्मैपदेषु' इत्युच्यते, परस्मैपदेषु तु विज्ञायते ॥ कथम् ? । "अनुदात्तङित आत्मनेपदम्" "भावकर्मणोरात्मनेपदम्" इत्येतौ द्वौ योगावुक्त्वा "शेषात्कर्तरि परस्मैपदम्" इत्युच्यते । एवं च न परस्मैपदेषूच्यते, परस्मैपदेषु विज्ञायते ॥

(प्रदीपः) नखल्विति । सामर्थ्यादिति भावः ॥

(उद्द्योतः) सामर्थ्यादिति । भाष्ये वक्ष्यमाणरीत्यर्थः ॥

(आक्षेपबाधकभाष्यम्)

कः पुनरर्हत्येतौ योगावुक्त्वा शेषात्कर्तरि परस्मैपदं वक्तुम् । किं तर्हि ? । अविशेषेण सर्वमात्मनेपदप्रकरणमनुक्रम्य "शेषात्कर्तरि परस्मैपदम्" इत्युच्यते ॥

(प्रदीपः) कः पुनरिति । समस्तमेवात्मनेपदप्रकरणं महावाक्यं नियमार्थम् । तत्रानियमेन लादेशेषु कृतेषु शिति विकरणे कृते नियमोयं प्रवर्तते—शदेः शित एव, न तु शत्स्यतीत्यादाविति भावः ।

(उद्द्योतः) यद्येतत्सूत्रद्वयोत्तरं शेषादित्युच्येत तर्हि निविशत इत्यादौ परस्मैपदस्याप्यापत्तिरित्याशयेनाह—समस्तमेवेति । एवं च तदपेक्ष एव शेषः शेषादिति सूत्रे । एवं च तस्याप्राप्त्या नियमेनैव लादेशा इति भावः । भाष्यात्मनेपदनियमविषयेप्यशेष एवति तात्पर्यम् । एवं च न परस्मैपदाश्रयत्वमिति बोध्यम् ॥ लादेशेषु कृतेष्विति । प्रसक्तेष्वित्यर्थः ॥ विकरणे इति । विकरणेभ्यो नियमो बलवानिति तु शित इत्येतत्सामर्थ्यादेतद्विषये नाश्रीयते इति भावः ॥ नन्वेवं शदेः शेषत्वाभावे शत्स्यतीत्यादावपि परस्मैपदनियमो न स्यादत आह—शदेः शित एवेति । तादृशशदिविषय एव नियम इत्यतादृशः शेष एवेति भावः ॥

(आक्षेपसाधकभाष्यम्)

एवमपि परस्मैपदाश्रयो भवति । कथम् ? । इदं तावदयं प्रष्टव्यः—यदीदं नोच्येत किमिह स्यादिति ॥ परस्मैपदमित्याह ॥ परस्मैपदमिति चेत्परस्मैपदाश्रयो भवति ॥

(प्रदीपः) एवमपीति । यद्यपि तात्पर्यपर्यालोचनेन प्रकरणस्य नियमार्थत्वं तथाप्येकैकसूत्रार्थपर्यालोचनकाले त्ववान्तरव्यापारसंभवाद्विध्यर्थता संभवत्येव । अनारम्भे शेषपक्षे निक्षेपाद् आरम्भे तत उद्धारात् ॥

(उद्द्योतः) विकरणेभ्यो नियमबलवत्त्वानाश्रयणमजानानः शङ्कते—भाष्ये—एवमपीति ॥ नन्वेतदनुक्तौ महावाक्यस्यासमाप्ततया शेषपदार्थानिर्णयेन शेषादित्यस्याप्रवृत्तेर्यदीदमित्यादि कथमत आह—यद्यपीति । अयं भावः—अनुदात्तङितो भावकर्मणोरित्येतद्द्वयं नियमार्थं शेषादिति च । तत्र शेषादितिसूत्रे शेषश्च तद्द्वयापेक्ष एव । इतरसूत्राणि तु शेषादिति प्राप्तपरस्मैपदबाधनेनात्मनेपदविधायकानि । तत्र शितः पूर्वमस्याप्राप्तेर्बाधकाभावात्परस्मैपदे जाते पश्चाज्जातनिवृत्त्ययोगेनाप्रामाण्यमस्यापद्यते इति भावः ॥ यदीदं नोच्येतेति भाष्येण बाधकत्वमेषामिति दर्शितम् ॥ अनारम्भे इति । बाधकशास्त्राभावेन शेषपक्षनिपातः । एवं च परस्मैपदोत्पत्तिर्निर्बाधैवेति भावः ॥ आरम्भ इति । स्वरूपकथनमिदम् ॥ ततः । शेषपक्षात् ॥ उद्धारात् । बहिर्भावात् ॥

(९३७ समाधानवार्तिकम् ॥ २ ॥)

॥ * ॥ सिद्धं तु लडादीनामात्मनेपदवचनात् ॥ * ॥

(भाष्यम्) सिद्धमेतत् । कथम् ? । "शदेर्लडादीनामात्मनेपदं भवति" इति वक्तव्यम् ।

(प्रदीपः) लडादीनामिति । आदिशब्दः प्रकारे येषु शिता भाव्यं ते लडादयः ॥

(उद्द्योतः) नन्वेवं लङादिष्वतिप्रसङ्गोऽत आह—आदिशब्द इति ॥

(आक्षेपभाष्यम्)

सिद्ध्यति । सूत्रं तर्हि भिद्यते ॥

(समाधानभाष्यम्)

यथान्यासमेवास्तु ।

(आक्षेपकारणभाष्यम्)

ननु चोक्तम्—*शदेः शितः परस्मैपदाश्रयत्वादात्मनेपदाभावः* इति ॥

(समाधानभाष्यम्)

नैष दोषः । शित इति नैषा पञ्चमी । का तर्हि ? । संबन्धे षष्ठी—शितो यः शदिः ॥ कश्च शितः शदिः ? ॥ प्रकृतिः । शदेः शित्प्रकृतेरिति ॥

(प्रदीपः) शित्प्रकृतेरिति । योग्यतया शित्प्रकृतित्वमाश्रित्य प्रागेव शिदुत्पत्तेरात्मनेपदं विधीयते ।

(उद्द्योतः) शिदुत्पत्तेः प्राक् शित्प्रकृतित्वमपि कथमत आह—योग्यतयेति ॥

(समाधानान्तरभाष्यम्)

अथ वाऽऽहायं 'शदेः शितः' इति । न च शदिः शिदस्ति । त एवं विज्ञास्यामः—शदेः शिद्विषयादिति ॥

(प्रदीपः) शिद्विषयादिति । शिद्विषयत्वाच्छदिरेव शिच्छब्देनाभिधीयते ॥

(उद्द्योतः) शदिरेवेति । शदेः शित इति समानाधिकरणे इति भावः ॥

(समाधानान्तरभाष्यम्)

अथ वा यद्यपि तावदेतदन्यत्र भवति 'विकरणेभ्यो नियमो बलीयान्' इति । इहैतन्नास्ति । विकरणो हीहाश्रीयते 'शितः' इति ।

(प्रदीपः) अथ वेति । प्रकरणं नियमार्थम् । तत्र नियमात्पूर्वमात्मनेपदपरस्मैपदान्यनियमेन प्रवृत्तानि । तत्रैतत्सूत्रारम्भसामर्थ्यात्पूर्वं विकरणः प्रवर्तते, पश्चाच्छित एव शदेरात्मनेपदमिति नियमः ॥

(उद्द्योतः) नन्वनुदात्तङितौ भावकर्मणी च विहाय परिशिष्टस्यात्मनेपदवाक्यस्यावान्तरव्यापारापेक्षया विधित्वसंभवस्योक्तत्वात्कथमेतदत आह—प्रकरणमिति ॥ प्रवृत्तानि । प्रसक्तानि ॥ नन्वेवमपि शिदुत्पत्तेः प्राक् शेषत्वस्यैव सत्त्वेन विकरणेभ्यो नियमस्य बलवत्त्वात्परस्मैपदनियमो दुर्वारोऽत आह—तत्रैतदिति । "अनुपसर्गाद्वा" 'वृद्भ्यः स्यसनोः' इत्येतत्सामर्थ्यान्नियमस्य बलीयस्त्ववदेतत्सूत्रसामर्थ्यादेतद्विषये विकरणस्यैव बलवत्त्वं ज्ञाप्यत इत्यर्थः ॥

(अड्व्यवायेपि नियमप्रवृत्तिसाधनाधिकरणम्)

(१३८ आक्षेपवार्तिकम् ॥ ३ ॥)

॥ * ॥ उपसर्गपूर्वनियमेऽड्व्यवाय उपसंख्यानम् ॥ * ॥

(भाष्यम्) उपसर्गपूर्वनियमेऽड्व्यवाय उपसंख्यानं कर्तव्यम् । न्यविशत व्यक्रीणीत ॥ किं पुनः कारणं न सिद्ध्यति ? । अटा व्यवहितत्वात् ॥

(प्रदीपः) न्यविशतेति । ननु विकरणेभ्यो नियमो बलीयानिति प्रागेव विकरणोत्पत्तेर्नियमेन भाव्यं ततो नित्यत्वात्पूर्वं विकरणः ततोऽडागम इति किं वार्तिकेन । उच्यते—एतदनाश्रित्यैतदुक्तम् ॥

(उद्द्योतः) पूर्वं विकरण इति । सार्वधातुकप्रसक्तिमात्रेणेति भावः ॥ अनाश्रित्येति । कृतोपि विकरणो न व्यवधायक इत्येवमपि ज्ञापकस्य नेतुं शक्यत्वात्तदनाश्रयणमिति भावः ॥ एवं लावस्थायामडिति पक्षमात्मनेपदप्रकरणस्य तिङ्सत्वादिसूत्रैणैकवाक्यतेतिपक्षं चानाश्रित्येदमित्यपि बोध्यम् ॥

(आक्षेपबाधकभाष्यम्)

ननु चायमड् धातुभक्तो धातुग्रहणेन ग्रहीष्यते ॥

(आक्षेपसाधकभाष्यम्)

न सिध्यति । अङ्गस्य ह्यडुच्यते, विकरणान्तं चाङ्गम्, सोसौ संघातभक्तो न शक्यो धातुग्रहणेन ग्रहीतुम् ॥

(आक्षेपबाधकभाष्यम्)

एवं तर्हीदमिह संप्रधार्यम्—अट् क्रियतां विकरण इति । किमत्र कर्तव्यम् ? । परत्वादडागमः ॥

(आक्षेपसाधकभाष्यम्)

नित्या विकरणाः । कृतेप्यटि प्राप्नुवन्त्यकृतेपि ॥

(आक्षेपबाधकभाष्यम्)

अडपि नित्यः । कृतेष्वपि विकरणेषु प्राप्नोत्यकृतेष्वपि प्राप्नोति ॥

(आक्षेपसाधकभाष्यम्)

अनित्योट् । अन्यस्य कृतेषु विकरणेषु प्राप्नोत्यन्यस्याकृतेषु । 'शब्दान्तरस्य च प्राप्नुवन्विधिरनित्यो भवति' ॥

(प्रदीपः) शब्दान्तरस्येति । विकरणास्तु शब्दान्तरादपि प्राप्नुवन्तो नानित्याः ॥

(उद्द्योतः) नानित्या इति । अस्येति मन्यत इति शेषः ॥ तदेवं स्थितमेतत्—विकरणेषु कृतेषु भवन्नट् विकरणान्तभक्तो धातुव्यवधायक इत्युपसंख्यानं कार्यमिति ॥

(आक्षेपबाधकभाष्यम्)

एवं तर्हीदमिह संप्रधार्यम्—अट् क्रियताम्, ला-

देश इति । किमत्र कर्तव्यम् । परत्वादडागमः ॥ नित्यो लादेशः । कृतेप्यटि प्राप्नोत्यकृतेपि प्राप्नोति । नित्यत्वाल्लादेशस्यात्मनेपद एवाडागमो भविष्यति ॥

(प्रदीपः) कृतेप्यटीति । धातुभक्तत्वादटस्तद्ग्रहणेन ग्रहणाद्व्यवधानाभावात् । अडागमस्त्वनित्यः । स हि लादेशेषु कृतेषु विकरणैर्नित्यत्वात्प्रतिबध्यते । विकरणेषु कृतेषु शब्दान्तरप्राप्त्या अनित्यः ॥

(उद्योतः) तत्र भाष्यकृद् विकरणोत्पत्तेः प्राक् नियमस्याटश्च संप्रधारणं करोति—एवं तर्हीति । लादेश इत्यनेन नियमो विवक्षितः ॥ ननु नियमोऽटि कृते न प्राप्नोत्यटा व्यवधानादत आह—धातुभक्तत्वादिति ॥ अटोपि कृताकृतप्रसङ्गित्वेन नित्यत्वमाशङ्क्याह—अडागम इति ॥ अटो विकरणापेक्षया कथमनित्यत्वमत आह—विकरणेष्विति ॥ भाष्ये—आत्मनेपदएवेति । नित्यत्वादटः पूर्वं नियमप्राप्तेरिति भावः ॥ अडागमो भविष्यतीति फलितनिर्देशः । तथा चोपसंख्यानं न कार्यमिति भावः ॥

(९३९ आक्षेपसाधकवार्तिकम् ॥ ४ ॥)

॥ * ॥ नित्यत्वाल्लादेशस्यात्मनेपदेऽडागम इति चेदटो नित्यनिमित्तत्वादात्मनेपदाभावः [तस्मादुपसंख्यानम्] ॥*॥

(भाष्यम्) नित्यत्वाल्लादेशस्यात्मनेपदेऽडागम इति चेदेवमुच्यते—अडपि नित्यनिमित्तः कृतेपि लादेशे प्राप्नोत्यकृतेपि प्राप्नोति । अटो नित्यनिमित्तत्वादात्मनेपदस्याभावः ॥ तस्मादुपसंख्यानम् । तस्मादुपसंख्यानं कर्तव्यम् ॥

(प्रदीपः) नित्यनिमित्तत्वादिति । कृतेपि लादेशे स्थानिवद्भावाल्लुङादिव्यपदेशोस्तीति प्रदर्शनार्थं निमित्तग्रहणमुपात्तम् । यद्यपि लादेशे कृते विकरणेन नित्यत्वादड् बाध्यते तथापि यस्य च लक्षणान्तरेण निमित्तं विहन्यते न तदनित्यम् । तत्रोभयोर्नित्ययोः परत्वादड् प्राप्नोति ॥ ननु भवतु परत्वादडागमः, तस्य तु धातुभक्तत्वादव्यवधायकत्वात्सिध्यत्यात्मनेपदम् ॥ नैष दोषः । तत्र ह्यन्तरङ्गत्वाल्लादेशेषु कृतेषु नियमात् पूर्वं नित्यत्वाद्विकरणेषु कृतेषु अडागमो विकरणान्तभक्तत्वाद्धातोर्व्यवधायक इति न्यादिभ्यः परे विश्यादयो निरन्तरा न संभवन्तीत्यात्मनेपदाप्रसङ्ग इत्येवं भाष्ये चोद्यं व्यवस्थाप्यते ॥

(उद्योतः) पुनरुपसंख्यानवाद्याह—नित्यत्वाल्लादेशस्येत्यादीति चेदिति ॥ अडपि नित्य इति वक्तव्ये निमित्तग्रहणं किमर्थमत आह—कृतेपीति । अन्यथा लादेशेषु कृतेषु लङादिपरत्वाभावादडाद्यभावशङ्का स्यादिति भावः ॥ तस्य धातुभक्तत्वादिति । लादेशेभ्यः परत्वादडागमे विकरणाभावात्स धातुभक्त इत्यर्थः ॥ सिध्यतीति । आत्मनेपदनियमः सिध्यतीत्यर्थः ॥ लादेशेषु । तिप्तसितिविहितेषु ॥ नियमात्पूर्वं नित्यत्वादिति । वृद्भ्यः स्यसनोरिति तु विकरणव्यवधानेपि नियमप्रवृत्तिरित्यर्थस्यैव ज्ञापकमिति भावः ॥ आत्मनेपदाप्रसङ्ग इति । नियमाप्रसङ्ग इत्यर्थः ॥ चोद्यम् । उपसंख्यानम् ॥ अटो नित्यनिमित्तत्वादित्युत्तरमुभयोर्नित्ययोर्नियमात् परत्वादटि प्राप्ते तं बाधित्वा विकरणे ततोऽटीति शेषपूरणेनेति भावः ॥

(आक्षेपबाधकभाष्यम्)

अन्तरङ्गस्तर्हि लादेशः ॥

(प्रदीपः) अन्तरङ्गस्तर्हीति ॥ लकारमात्रापेक्षत्वात् । अडागमस्तु लकारविशेषापेक्षत्वाद्बहिरङ्गः ॥

(उद्योतः) उभयोराश्रययोः कथमन्तरङ्गत्वबहिरङ्गत्वे अत आह—लकारेति । परनिमित्तकत्वादडागमो बहिरङ्ग इति वक्तुं युक्तं, तस्मिन्निति परिभाषासापेक्षत्वात्तस्य, विशेषापेक्षत्वेपि न बहिरङ्गत्वमिति प्रागुक्तम् ॥ प्रत्याख्यानुसिद्धान्तिनोऽन्तरङ्गस्तर्हीत्युक्तिर्भाष्ये । विधिवाक्यैनैषामेकवाक्यताश्रयणान्नियमोन्तरङ्ग इत्यर्थः ॥ उपसर्गकार्यं चान्तरङ्गमिति सुट्कादिति सूत्रे भाष्ये स्पष्टम् ॥

(आक्षेपसाधकभाष्यम्)

नैतद्विवदामहे—अन्तरङ्गो नान्तरङ्ग इति । अस्त्वयं नित्यश्चान्तरङ्गश्च । अत्र खलु लादेशे कृते त्रीणि कार्याणि युगपत् प्राप्नुवन्ति—विकरणाः, अडागमः, नियम इति । तद्यदि सर्वतो नियमो लभ्येत कृतं स्यात्, तत्तु न लभ्यम् ॥ अथापि विकरणात्पूर्वमडिति अड् लभ्येत, एवमपि कृतं स्यात् । तत्तु न लभ्यम् ॥ किं कारणम् ? । आङ्गात्पूर्वं विकरणा एषितव्यास्तरतस्तरन्तीत्येवमर्थम् । अडाड्भ्यामप्यन्यदाङ्गं पूर्वमेषितव्यमुपार्च्छदित्येवमर्थम् । तत्र ह्याटि कृते सार्ट्कस्य ऋच्छिभावः प्राप्नोति ॥

(प्रदीपः) नैतदिति । न लादेशेन सह संप्रधारणा किं तु नियमेन सहेति भावः ॥ तत्तु न लभ्यमिति ॥ ननु पूर्वमेव ज्ञापकाद्विकरणेभ्यो नियमस्य बलीयस्त्वं प्रतिपादितं तत्किमुच्यते तत्तु न लभ्यमिति ॥ उच्यते—अन्यथापि तज्ज्ञापकं समर्थयितुं शक्यते—कृतोपि विकरणो न व्यवधायक इति । यद्येवं नित्य एव नियमः । नैतदस्ति । यत्र केवलो विकरणो व्यवधायकस्तत्र भवतु नित्यो नियमः यथा निवेक्ष्यते निविशत इति । यत्र तु विकरणे कृतेऽडागमस्तत्राटो व्यवधायकत्वान्नियमो न प्राप्नोति ॥ तरत इति । अत्र पूर्वमित्त्वे सति रूपं न सिध्यति ॥ आटि कृतइति । आटश्चेति वृद्धिरेकादेशः प्राप्नोति, ऋच्छिभावश्च । तत्र वर्णमात्राश्रयत्वादेकादेशोन्तरङ्गः । नानाश्रयत्वाच्च वार्णादाङ्गं बलीय इति नास्ति । ततश्चैकादेशे कृते तस्यादिवद्भावादृच्छिभावः प्राप्नोति । तत ऋच्छदिति स्यात्, न त्वार्च्छदिति ॥

(उद्द्योतः) एतदुत्तरग्रन्थस्त्वेकदेशिनोः 'अथ वा नेट्—'इत्येतत्पर्यन्तम् ॥ तदाशयश्च पूर्वपक्षमुखेन मयोच्यते—**नन्वन्तरङ्गस्तर्हि लादेश** इत्यत्र लादेशशब्देन नियमो विवक्षितः, उत **तिङ्सिति-विधिः** । नाद्यः । **नोर्वंश** इत्यादेः पदान्तरापेक्षत्वेन बहिरङ्गत्वात् । तस्माद् द्वितीयो ग्राह्यस्तत्राह—**नैतदिति** ॥ **अयमिति** । तिङ्सितिविधिः ॥ न तु तेन सह संप्रधारणेति भावः ॥ केन तर्हि संप्रधारणेत्यत्राह—**अत्र खल्विति** ॥ **लादेशे कृते इति** । जातस्यापि लुकेव निवृत्तिः । प्रसक्ते इति वार्थः ॥ **सर्वत इति** । विकरणादडागमाच्चेत्यर्थः ॥ **तत् तु न लभ्यमिति** । नियमात्पूर्वं नित्यत्वाद्विकरणप्रवृत्तेस्तत्र कृतेपि तत एव नियमात्पूर्वमाडागमस्य च प्रवृत्तेरिति भावः ॥ तत्र शङ्कते—**ननु पूर्वमेवेति** ॥ **यत्रेति** । तथा च नियमो न नित्य इति भावः ॥ ननु विकरणात्पूर्वमडागमो न लभ्य इत्यर्थकं **तत्तु न लभ्यमित्ययुक्तं**, विकरणस्यापि शब्दान्तरात्प्राप्त्याऽनित्यत्वात् । न च शब्दान्तरस्येति वाचनिकं, किं तु न्यायो यद्व्यक्तिसंबन्धितया पूर्वं प्राप्नोति तद्व्यक्तिसंबन्धित्वेनाप्राप्त्या कृताकृतप्रसङ्गित्वाभाव इति । स च शब्दान्तरात्प्राप्तावपि तुल्य इति विकरणात् पूर्वमटि विकरणोत्तरं ततः पूर्वं वा नियमो भविष्यतीति नार्थ उपसंख्यानेनेत्याशयेन पृच्छति—**किं कारणमिति** ॥ उपसंख्यानबीजमाह—**आङ्गादिति** ॥ आङ्गप्रवृत्त्युत्तरं विकरणे तरत इत्यत्रानिष्टमाह—**अत्रेति** ॥ अडाटोर्बाधकस्याङ्गस्य बाधको विकरणः सुतरामडाटोर्बाधक इति कैमुतिकन्यायं वक्तुं भाष्ये—**अडाड्भ्यामपीति** ॥ ननु **वार्णादाङ्गमित्येकादेशात्पूर्वमृच्छिभावे निर्दिश्यमानपरिभाषया न दोषः** । किं चाटः शबन्ताङ्गभक्तत्वेनाद्विशिष्टस्यानित्त्वाभावान्न दोषोऽत आह—**आटश्चेति वृद्धिरिति** ॥ **नानाश्रयत्वादिति** । वस्तुतस्तदनाश्रित्येदम् ॥ **तस्यादिवद्भावादिति** । एवं चातिदेशविषये न **निर्दिश्यमान**परिभाषाप्रवृत्तिः शबन्ताङ्गभक्तत्वेपि आद्विशिष्टस्यानित्त्वं च सुलभमिति भावः ॥ भाष्योक्तस्योपार्छेदित्यस्योपसर्गाद्दतीति वृद्ध्यापि सिद्धिरत आह—**न त्वार्छेदितीति** ॥

(आक्षेपबाधकभाष्यम्)

ननु च ऋच्छिभावे कृते शब्दान्तरस्याकृत आडिति कृत्वा पुनराड् भविष्यति ॥

(प्रदीपः) **ननु चेति** । वत्सवत्प्रवृत्त्या कार्यमिह शास्त्रे संभवतीति भावः ॥

(उद्द्योतः) भाष्ये लक्ष्ये लक्षणस्येतिन्यायाविषयं बोधयितुं—**शब्दान्तरस्येति** ॥ नन्वेवमुदवोढामित्यत्र **लक्ष्ये लक्षणस्ये**तिन्यायेन पुनर्वृद्धिवारणं सप्तमे कैयटेन वक्ष्यमाणं विरुध्येत ततो हि विकारकृतं न शब्दान्तरत्वमिति लभ्यते इति चेन्न । अत्रत्यस्यैकदेश्युक्तित्वेनादोषात् तदाह—**वत्सवदिति** । स न्यायोऽनित्य इति भावः । गविस्थितदुग्धशेषपयसो ग्रहणाय यथा वत्सः प्रवर्त्तते तद्वदिति तात्पर्यम् ॥ क्वचित्तु **पर्जन्यवदिति** पाठस्तत्रायमर्थः । यथा पर्जन्यः स्वयं पूर्णे कृतेपि क्षेत्रे पुनःपुनर्वर्षतीति ॥

(आक्षेपसाधकभाष्यम्)

पुनर्ऋच्छिभावः पुनराडिति चक्रकमव्यवस्था प्राप्नोति ॥

(उद्द्योतः) भाष्ये—**पुनर्ऋच्छिभाव इति** । विकारान्यानुपूर्व्यन्वयेऽपि यदि पुनराट्, तत एव तुल्यन्यायात्पुनर्ऋच्छिभावोऽपि स्यादित्यभिमानः ॥

(समाधानभाष्यम्)

नैष दोषः । यत्तावदुच्यते—आङ्गात्पूर्वं विकरणा एषितव्याः तरतः तरन्तीत्येवमर्थमिति । भवेत्सिद्धं यत्र विकरणा नित्या आङ्गमनित्यं तत्राङ्गात्पूर्वं विकरणाः स्युः । यत्र तु खलूभयं नित्यं परत्वात्तत्राङ्गं तावद्भवति ॥

यदप्युच्यते—अडाड्भ्यामप्यन्यदाङ्गं पूर्वमेषितव्यमुपार्च्छेदित्येवमर्थमिति । अस्त्वत्राट्, आटि कृते साट्कस्य ऋच्छिभावः । ऋच्छिभावे कृते शब्दान्तरस्याकृत आडिति कृत्वा पुनराड् भविष्यति ॥

(प्रदीपः) **यत्तावदिति** । तरत इत्यत्रानित्यमित्त्वं विकरणस्तु नित्य इति स एव प्रवर्तते ॥ **यत्रत्विति** । यथा तरतीति ॥ **अस्त्वत्राडिति** । परत्वादृच्छिना भाव्यम् ।

(उद्द्योतः) **यत्र खलूभयमिति** । एवं च तुल्यन्यायाद्द्वयोरनित्ययोरपि परत्वादटि सति न दोष इत्युपसंख्यानं न कार्यं विकरणाटोर्द्वयोरप्यनित्यत्वं तु दर्शितमेव । **शब्दान्तरप्राप्तस्ये**त्यनाश्रयेण तूभयोर्नित्यत्वं बोध्यम् ॥ **परत्वादिति** । अङ्गिकारे ऋच्छिः सा (ऋच्छेर) वकाशः । आटोन्येऽजादयः ॥

(आक्षेपान्तरस्मारकभाष्यम्)

ननु चोक्तम्—पुनर्ऋच्छिभावः पुनराडिति चक्रकमव्यवस्था प्राप्नोतीति ॥

(समाधानभाष्यम्)

नैष दोषः । चक्रकेष्विष्टतो व्यवस्था ॥

(प्रदीपः) अभ्युपगम्यवादेन त्वेतदुच्यते—**चक्रकेष्विति** । व्यवस्थाकारिणा शास्त्रेण भाव्यमित्यव्यवस्थाहेतुः पुनः प्रवृत्तिर्न भविष्यतीत्यर्थः ॥ तदेवं स्थितमेतदन्तरङ्गत्वाल्लादेशेषु कृतेषु परत्वादडागमः ॥ न चायं नियमः—**शब्दान्तरस्य प्राप्नुवन्विधिरनित्यो भवति, न तु शब्दान्तरादिति** । यतोऽडागमस्यानित्यत्वं स्याद् विकरणस्य नित्यत्वम् । कृताकृतप्रसङ्गित्वात्तु द्वयोरपि नित्यत्वम् । अङ्गत्वाकृत्याश्रयणाद्वा नास्ति शब्दान्तरप्राप्तिरटः ॥

(उद्द्योतः) **अभ्युपगम्यवादेन त्विति** । एवं लक्ष्ये लक्षणस्येतिन्यायानाश्रयणेन चक्रकापादानमपि तथैवेति ध्वनितम् । एकदेश्युक्तित्वं न ध्वनितम् ॥ **चक्रकेष्विष्टतो व्यवस्थेति** स्वशास्त्रीयो न्याय इत्याह—**व्यवस्थेति** । अन्यथान्वाख्यानापर्यवसानं स्यादिति भावः ॥ नन्वत्र न्यायात्सिद्धावप्युपसर्गनियमे न्यायाभावादुपसंख्यानमावश्यकमत आह—**तदेवमिति** ॥ **लादेशेषु** । तिङ्सितिसूत्रेण ॥ **परत्वादडागम इति** । परत्वाद्विकरणात् पूर्वं तत्र कृते तस्य धातु-

भक्तत्वादव्यवधायकत्वेन नियमसिद्धिरित्यर्थः ॥ न चायं नियम इति पाठस्तदाह—न त्वित्यादि । न्याय इति पाठेऽयमेव भाष्योऽयं नेति न न्यायो न युक्तमित्यर्थः ॥

(सिद्धान्तिसमाधानान्तरभाष्यम्)

अथ वा नेरिति नैषा पञ्चमी ॥ का तर्हि ? ॥ विशेषणषष्ठी नेर्यो विशिः ॥ कश्च नेर्विशिः ? ॥ विशेष्यः । व्यवहितश्चापि शक्यते विशेषयितुम् ॥

(प्रदीपः) नेर्यो विशिरिति । व्यवहितश्चाप्यर्थद्वारेण विशेष्यत्वात्संबन्धी भवतीत्यर्थः ॥

(उद्द्योतः) संबन्धीति। स्वघोत्यार्थनिरूपितविशेष्यतावदर्थवत्त्वं संबन्धो बोध्यः ॥ परिव्यवेभ्य इत्यादावपि षष्ठ्यर्थे पञ्चमी बोध्या । पञ्चमीपक्षेपि वा नेः परत्वयोग्यस्येत्यादिक्रमेणार्थः ॥

(सिद्धान्तिसमाधानान्तरभाष्यम्)

अथ वा निरपि पदं विशिरपि पदम् । पदविधिश्च समर्थानाम् । व्यवहितेपि सामर्थ्यं भवति ॥ शदेः शितः ॥ ६० ॥

(प्रदीपः) अथ वेति । नेर्विश इत्यस्यायमर्थः—निशब्दात्परमात्मनेपदान्तं विश्यवयवपदं साधु भवतीति सत्यप्यडागमे नेः पदमनन्तरमेवेति दोषाभावः ॥ विशिरपीति । विशिशब्देन विश्यवयवः समुदाय उपचारादभिधीयते ॥ पदविधिश्चेति । न्यायप्राप्तार्थानुवादोऽयं न त्वेतत्प्रकृते उपयुज्यते इत्याहुः ॥ ६० ॥

(उद्द्योतः) अयमर्थ इति । पदसंस्कारप्रस्तावात्तात्पर्यवृत्त्याऽयं सूत्रार्थ इति भावः ॥ अथ विशिः कथं पदमत आह—विशीति । न्यायेति । नेः सकाशादर्थविशेषं प्राप्तो विशिरित्यर्थे तात्पर्यं दर्शयितुं समर्थानामित्युक्तम्, न त्वत्र तत्परिभाषोपस्थितिः । सुबन्तत्वेन पदत्वेन वा निमित्तकोटावप्रवेशात् । अत एव समर्थसूत्रे भाष्यकारो वक्ष्यति—एकार्थीभावः सामर्थ्यम्, विभक्तिविधौ च नोपस्थितिरितीति दिक् ॥ न चात्र पक्षद्वयेप्युपसर्गान्तरव्यवधानेपि प्रवृत्त्यापत्तिरिति वाच्यम् । तेषामनभिधानात् ॥ ६० ॥

(१५१ आत्मनेपदनियमसूत्रम् ।१। ३ । २ आ. २२ सू.)

२०९ पूर्ववत्सनः १।३।६२ ॥

(पूर्वत्वावधिनिर्णयाधिकरणम्)

(आक्षेपभाष्यम्)

किमिदं पूर्वग्रहणं सनपेक्षम्—प्राक् सनो येभ्य आत्मनेपदमुक्तं तेभ्यः सन्नन्तेभ्योपि भवतीति । आहोस्विद् योगापेक्षम्—प्रागेतस्माद्योगाद्येभ्यो योगेभ्य आत्मनेपदमुक्तं तेभ्यः सन्नन्तेभ्योपि भवतीति ॥

किं चातः? ।

यदि सनपेक्षम्, निमित्तमविशेषितं भवति 'पूर्ववत्सनः' न ज्ञायते-किमन्ताद्भवितव्यमिति ॥ अथ योगापेक्षम्, उत्तरत्र विधिर्न प्रकल्पेत-बुभुक्षते उपयुयुक्षत इति ॥

(प्रदीपः) पूर्ववत्सनः ॥६२॥ पूर्वशब्दः संबन्धिशब्दत्वादवधिमपेक्षते तत्र कोऽत्रावधिरभिप्रेत इति पृच्छति—किमिदमिति ॥ येभ्य इति । योगस्थेभ्यो धातुभ्यो विधानाद्योगेभ्यो विहितमित्युच्यते ॥ पक्षद्वयेपि तेन तुल्यमिति तृतीयान्ताद्वतिः न तु पञ्चम्यन्तात् । लक्षणाभावात् । तुल्यार्थैरिति विहिता तृतीया सर्वविभक्त्यर्थानन्तर्भावयतीति पञ्चम्यर्थस्यात्र ग्रहणमुपपन्नमेव । यथा ब्राह्मणवद्वैश्यादधीत इति ब्राह्मणादिव वैश्यादधीत इत्यर्थः । वैश्यापादानकस्याध्ययनस्य ब्राह्मणापादानकमध्ययनमुपमानम् । तत्र च ब्राह्मणशब्दो वर्तते । तेन ब्राह्मणेन तुल्यं वैश्यादधीत इति तृतीयान्ताद्वतिः । एवमिहापि पूर्ववदिति द्रष्टव्यम् ॥ किमन्तादिति । ततश्चाप्रतिपत्तिः स्यात् । यदि नामात्मनेपदनियमविधानसामर्थ्यादनेन सर्वधातुभ्य आत्मनेपदं भवतीत्येतल्लभ्येत विषयविभागस्तु न ज्ञायेतेति भावः ॥

(उद्द्योतः) पूर्ववत्सनः ॥ ६२ ॥ धातुभ्यः परस्य लस्य विधीयमानमात्मनेपदं कथं योगेभ्यः स्यादत आह—योगस्थेभ्य इति । मञ्चाः क्रोशन्तीतिवदिति भावः ॥ भाष्ये येभ्य इति निर्देशात् पञ्चम्यन्ताद्वतिरिति भ्रमं वारयति—पक्षद्वयेपीति ॥ तर्हि पञ्चम्यन्तप्रयोगस्य का गतिरत आह—तुल्यार्थैरिति ॥ नन्वात्मनेपदेन स्वयोग्यप्रकृतेराक्षेपाद्दोषाभावोऽत आह—ततश्चेति ॥ तामुपपादयति—यदीति । यदि नामात्मनेपदनियमविधानसामर्थ्यादप्रतिपत्तिः स्यात् तर्हीति शेषः । तर्ह्यनेनेत्यन्वयः ॥

(समाधानभाष्यम्)

यथेच्छसि तथास्तु ॥

(सनपेक्षाभ्युपगमभाष्यम्)

अस्तु तावत्सनपेक्षम् ॥

(आक्षेपस्मारणभाष्यम्)

ननु चोक्तम्—निमित्तमविशेषितं भवतीति ॥

(समाधानभाष्यम्)

निमित्तं च विशेषितम् । कथम् । सनमेवात्र निमित्तत्वेनापेक्षिष्यामहे । पूर्ववत्सन आत्मनेपदं भवति । कुतः? । सन इति ॥

(प्रदीपः) सनमेवेति । प्रत्यासत्त्येति भावः ॥

(योगापेक्षाभ्युपगमभाष्यम्)

अथ वा पुनरस्तु योगापेक्षम् ॥

(आक्षेपस्मारणभाष्यम्)

ननु चोक्तम्—उत्तरत्र विधिर्न प्रकल्पेतेति ॥

(समाधानभाष्यम्)

विधिश्च प्रकृतः ॥ कथम्?। उत्तरत्रापि "पूर्ववत्सन" इत्येवानुवर्तिष्यते ॥

(प्रदीपः) **उत्तरत्रापीति।** उत्तरेषु योगेषु वाक्यभेदेन **पूर्ववत्सन** इत्येतत्संबध्यते। प्रोपाभ्यां युजेरात्मनेपदं भवति। ततः **पूर्ववत्सन** इति ॥

(उद्द्योतः) अनुवृत्तस्यैकवाक्यतया संबन्धे केवलेभ्य आत्मनेपदं न स्यादत आह—**वाक्यभेदेनेति।** पूर्ववद्ग्रहणानुवृत्तिसामर्थ्यात्। अन्यथा सन इत्येवानुवर्तयेदिति भावः ॥

(विधिपक्षस्थापनाधिकरण आक्षेपभाष्यम्)

किमर्थं पुनरिदमुच्यते? ॥

(प्रदीपः) **किमर्थमिति।** विधिनिषेधोभयपक्षसंभवात्प्रश्नः ॥

(उद्द्योतः) सूत्रस्यावश्यारभ्यत्वात्प्रयोजनप्रश्नोऽनुपपन्नोऽत आह—**विधीति।** अभिधेयप्रश्नोयमिति भावः ॥

(१४० समाधानवार्तिकपूर्वखण्डम् ॥ १ ॥)

॥ * ॥ पूर्ववत्सन इति शदिम्रियत्यर्थम् ॥ * ॥

(भाष्यम्) **शदिम्रियत्यर्थोऽयमारम्भः। शदिम्रियतिभ्यां सन्नन्ताभ्यामात्मनेपदं मा भूदिति ॥**

(१४१ समाधानसाधकवार्तिकपरखण्डम् ॥ २ ॥)

॥ * ॥ इतरथा हि ताभ्यां सन्नन्ताभ्यामात्मनेपदप्रतिषेधः ॥ * ॥

(भाष्यम्) **इतरथा हि अनुच्यमानेऽस्मिन् शदिम्रियतिभ्यां सन्नन्ताभ्यामात्मनेपदस्य प्रतिषेधो वक्तव्यः स्यात्। शिशत्सति। मुमूर्षति ॥**

(उद्द्योतः) भाष्ये इतरथाहीत्यस्य व्याख्या–ऽनुच्यमाने इति। शदिम्रियतिपरतयाऽव्याख्यानेऽन्यथा व्याख्याने इति भावः ॥ विधायकतया व्याख्यातेनानेनैव प्राप्तस्य प्रतिषेधो वाच्य इति तात्पर्यम् ॥

(आक्षेपभाष्यम्)

कथं पुनः 'पूर्ववत्सनः' इत्यनेन शदिम्रियतिभ्यां सन्नन्ताभ्यामात्मनेपदस्य प्रतिषेधः शक्यो विज्ञातुम्?।

(समाधानभाष्यम्)

प्रतिनिर्देशोयम्। कामचारश्च प्रतिनिर्देशे वाक्यशेषं समर्थयितुम्। तद्यथा—'उशीनरवन्मद्रेषु यवाः' सन्ति, न सन्तीति। 'मातृवदस्याः कलाः' सन्ति, न सन्तीति। एवमिहापि पूर्ववद्भवति, न भवतीति। न भवतीत्येवं वाक्यशेषं समर्थयिष्यामहे—यथा पूर्वयोर्योगयोः सन्नन्ताभ्यामात्मनेपदं न भवति, एवमिहापि शदिम्रियतिभ्यां सन्नन्ताभ्यामात्मनेपदं न भवतीति ॥

(प्रदीपः) **यथापूर्वयोरिति।** 'नानोर्ज्ञः' प्रत्याङ्भ्यांश्रुव इत्येतयोः। इह च शदिम्रियती अनुवर्तेते इति भावः ॥

(उद्द्योतः) ननु पूर्ववदित्युक्त्या नानोर्ज्ञः प्रत्याङ्भ्यामित्येतौ कथं प्रतिपत्तुं शक्याविल्यत आह—**इह चेति।** एवं च शदिम्रियत्यपेक्षया पूर्वस्य परिग्रहान्न दोष इति भावः ॥

(आक्षेपभाष्यम्)

यदि तर्हि शदिम्रियत्यर्थोयमारम्भः, विधिर्न प्रकल्पते—आसिसिषते। शिशयिषते ॥ अथ विध्यर्थः। शदिम्रियतिभ्यां सन्नन्ताभ्यामात्मनेपदं प्राप्नोति ॥

(समाधानभाष्यम्)

यथेच्छसि तथास्तु ॥

(प्रदीपः) **यथेच्छसीति।** निषेधपक्षेपि निषेधादेव सन्नन्तात् पूर्ववद्विधिरनुमीयते। विधिपक्षे शदिम्रियत्योः सनो नेत्यनुवृत्त्या न भविष्यति ॥

(उद्द्योतः) **पूर्ववद्विधिरिति।** पूर्ववदिति तु ज्ञापकसिद्धस्यासार्वत्रिकत्वादिष्टानुरोधाद्वा लब्धम् ॥

(प्रतिषेधार्थताभ्युपगमभाष्यम्)

अस्तु तावत्प्रतिषेधार्थः ॥

(आक्षेपस्मारणभाष्यम्)

ननु चोक्तम्—विधिर्न प्रकल्पते—इति ॥

(समाधानभाष्यम्)

विधिश्च प्रकृतः ॥ कथम्?। एतदेव ज्ञापयति सन्नन्तादात्मनेपदं भवतीति। यदयं शदिम्रियतिभ्यां सन्नन्ताभ्यामात्मनेपदस्य प्रतिषेधं शास्ति ॥

(विध्यर्थताभ्युपगमभाष्यम्)

अथ वा पुनरस्तु विध्यर्थः ॥

(आक्षेपस्मारणभाष्यम्)

ननु चोक्तम्—शदिम्रियतिभ्यां सन्नन्ताभ्यामात्मनेपदं प्राप्नोति—इति ॥

(समाधानभाष्यम्)

नैष दोषः। प्रकृतं 'सनो न' इत्यनुवर्तिष्यते ॥ क्व प्रकृतम्?। "ज्ञाश्रुस्मृदृशां सनः"। "नानोर्ज्ञः" सकर्मकात्सनो न भवति। "प्रत्याङ्भ्यां श्रुवः" सनो न। "शदेः शितः" सनो न। "म्रियतेर्लुङ्लिङोश्च" सनो नेति। इहेदानीं "पूर्ववत्सनः"

इति सन इत्यनुवर्तते, नेति निवृत्तम् ॥ एवं च कृत्वा सोप्यदोषो भवति, यदुक्तम्—निमित्तमविशेषितं भवतीति ॥ नैव वा पुनरत्र शदिम्रियतिभ्यां सन्नन्ताभ्यामात्मनेपदं प्राप्नोति । किं कारणम्? । "शदेः शितः" इत्युच्यते । न च शदिरेवात्मनेपदस्य निमित्तम् । किं तर्हि ? । शिदपि निमित्तम् ॥ अथापि शदिरेव शित्परस्तु निमित्तम् । न चायं सन्परः शित्परो भवति ॥

(प्रदीपः) एवं च कृत्वेति । द्वितीयस्य सन्ग्रहणस्येहानुवृत्त्येति भावः ॥ न च शदिरेवेति । सामग्र्याः कारणत्वं न केवलस्य शदेः, सा चेह सामग्री नास्ति सनः पूर्वस्य शदेः शितोऽभावात् ॥ अथापीति । शिता विशेष्यमाणत्वाच्छदेरेव प्राधान्यात् ॥

(उद्योतः) द्वितीयस्येति । एवं च सनपेक्षेपि पूर्वत्वे विशायमाने न कश्चिद्दोष इति स एव सिद्धान्तो विधिपक्षश्चेति भावः ॥ सामग्र्या इति । शदेः शितश्च पृथङ्निमित्तत्वमिति भ्रमो न कार्य इति भावः ॥ शदेः शितोऽभावादिति । शदिप्रकृतिकशितोऽभावादित्यर्थः ॥ पूर्वस्माद्भेदमाह—शितेति ॥

(आक्षेपभाष्यम्)

यत्र तर्हि शिन्नाश्रीयते "म्रियतेर्लुङ्लिङोश्च" इति ॥

(प्रदीपः) यत्र तर्हीति । म्रियतेर्ङित्वात् पूर्ववत्सन इति सन्नन्तात्प्राप्नोत्येवेति भावः ॥

(उद्योतः) म्रियतिमात्रस्यात्मनेपदनिमित्तत्वाभावादाह—म्रियतेरिति ॥ प्राप्नोतीति । लुङ्लिङोरिति शेषः ॥

(समाधानभाष्यम्)

अत्रापि न म्रियतिरेवात्मनेपदस्य निमित्तम् ॥ किं तर्हि?। लुङ्लिङावपि निमित्तम् ॥ अथापि म्रियतिरेव लुङ्लिङ्परस्तु निमित्तम् । न चायं सन्परः लुङ्लिङ्परो भवति ॥

(प्रदीपः) अत्रापीति । म्रियतेर्लुङ्लिङोश्चेति नियमार्थमारब्धमिति भावः ॥

(उद्योतः) नियमार्थमिति । ङित्वादेव सिद्ध इति भावः ॥ भाष्ये—लुङ्लिङ्पर इति । म्रियतिपरलुङ्लिङ्रूपस्येत्यर्थे तथा फलतीति भावः ॥ एवं च शदिम्रियतिभ्यां सन्नन्ताभ्यां न भवतीत्यर्थस्य वक्तुमयोग्यतया गुरुभूताभावे तात्पर्यं तन्मूलविधिकल्पनं चेति गौरवभिया विधित्वमेव युक्तमिति तात्पर्यम् ॥

(कार्यातिदेशस्थापनाधिकरणम्)

(आक्षेपभाष्यम्)

किं पुनः पूर्वस्य यदात्मनेपददर्शनं तत्सन्नन्तस्यातिदिश्यते ? ॥

(प्रदीपः) किं पुनरिति । किमयं कार्यातिदेशः—यथा पूर्वस्मादात्मनेपदं विधीयते तथा सन्नन्तादपीति । आहोस्विन्निमित्तातिदेशः पूर्वस्य यन्निमित्तं ङित्त्वादि तत्सन्नन्तस्यातिदिश्यते । निमित्ते चातिदिष्टे तत्प्रयुक्तत्वादेव कार्यं भवतीति प्रश्नः ॥

(उद्योतः) प्राधान्येन कार्यातिदेशस्यैवौचित्यात्प्रश्नानुपपत्तिरत आह—किमयमिति । कार्यातिदेशेऽव्याप्तेर्निमित्तातिदेशोपि शङ्कित इति भावः ॥

(इष्टापत्तिभाष्यम्)

एवं भवितुमर्हति ॥

(९४२ आक्षेपवार्तिकम् ॥ ३ ॥)

॥ * ॥ पूर्वस्यात्मनेपददर्शनात्सन्नन्तादात्मनेपदभाव इति चेज्जुपादिष्वप्रसिद्धिः ॥ * ॥

(भाष्यम्) पूर्वस्यात्मनेपददर्शनात्सन्नन्तादात्मनेपदं भवतीति चेद् गुपादिष्वप्रसिद्धिः । गुपादीनां न प्राप्नोति । जुगुप्सते मीमांसत इति । न ह्येतेभ्यः प्राक्सन आत्मनेपदं नापि परस्मैपदं पश्यामः ॥

(प्रदीपः) नह्येतेभ्य इति । नित्यसन्विषयत्वात् ॥

(९४३ समाधानवार्तिकम् ॥ ४ ॥)

॥ * ॥ सिद्धं तु पूर्वस्य लिङ्गातिदेशात् ॥ * ॥

(भाष्यम्) सिद्धमेतत् ॥ कथम् ? । पूर्वस्य यदात्मनेपदलिङ्गं तत्सन्नन्तस्याप्यतिदिश्यते ॥

(उद्योतः) भाष्ये—लिङ्गातिदेशादिति । पूर्वस्य यल्लिङ्गं ङित्त्वादि तदतिदिश्यत इत्यर्थः ॥

(९४४ दूषणाक्षेपवार्तिकम् ॥ ५ ॥)

॥ * ॥ कृञादिषु तु लिङ्गप्रतिषेधः ॥ * ॥

(भाष्यम्) कृञादिषु तु लिङ्गस्य प्रतिषेधो वक्तव्यः । अनुचिकीर्षति पराचिकीर्षतीति ॥

(प्रदीपः) कृञादिष्विति । अनुपराभ्यां कृञ इत्यनेन परस्मैपदमेव विधीयते, न तु ञित्त्वं निवर्त्यते । पूर्वकार्ये त्वतिदिश्यमाने अत्र दोषाभावः । परस्मैपदेनात्मनेपदस्य बाधितत्वात् पूर्वस्यात्मनेपदकार्यादर्शनात्सन्नन्तस्याप्रसङ्गात् ॥

(उद्योतः) ननु कर्त्रभिप्राये क्रियाफले सर्वथा तज्ज्ञाननिवृत्तयेनुपराभ्यामित्यनेन ञित्त्वस्यैव बाधोऽत आह—अनुपराभ्यामिति । परस्मैपदनियमेनैवेष्टसिद्धेर्निमित्तनिवर्तनमयुक्तमिति भावः ॥

(कार्यातिदेशपक्षाभ्युपगमभाष्यम्)

अस्तु तर्हि-प्राक्सनो येभ्य आत्मनेपदं दृष्टं तेभ्यः सन्नन्तेभ्योपि भवतीति ॥

(आक्षेपकारणभाष्यम्)

ननु चोक्तं *पूर्वस्यात्मनेपददर्शनात्सन्नन्तादात्मनेपदभाव इति चेद्गुपादिष्वप्रसिद्धिः* इति ॥

(समाधानभाष्यम्)

नैष दोषः । अनुबन्धकरणसामर्थ्याद्भविष्यति ॥

(प्रदीपः) अनुबन्धेति । तत्सामर्थ्यात्सन्न व्यवधायकः॥

(उद्द्योतः) तत्सामर्थ्यादिति । नित्यसन्नन्तत्वान्न किंचित्प्रयोजनसंभव इति भावः ॥

(समाधानान्तरभाष्यम्)

अथ वा—अवयवे कृतं लिङ्गं समुदायस्य विशेषकं भवति । तद्यथा—गोः सक्थनि कर्णे वा कृतं लिङ्गं समुदायस्य विशेषकं भवति ॥

(प्रदीपः) अथ वेति । समुदाये लिङ्गासङ्गस्य उपायोऽवयवे लिङ्गासङ्गः ॥

(उद्द्योतः) परिभाषाया अबाधेनोपपत्तौ बाधो न न्याय्योऽतः पक्षान्तरमित्याह—समुदायेति । सामर्थ्यात्परिभाषाबाधो वा सामर्थ्यात्समुदायोपकारकत्वं वेति पक्षयोर्भेदः ॥

(आक्षेपभाष्यम्)

यद्यवयवे कृतं लिङ्गं समुदायस्य विशेषकं भवति जुगुप्सयति मीमांसयतीत्यत्रापि प्राप्नोति ॥

(समाधानभाष्यम्)

नैष दोषः । अवयवे कृतं लिङ्गं कस्य समुदायस्य विशेषकं भवति ? यं समुदायं योऽवयवो न व्यभिचरति । सनं च न व्यभिचरति । णिचं च पुनर्व्यभिचरति । तद्यथा—गोः सक्थनि कर्णे वा कृतं लिङ्गं गोरेव विशेषकं भवति न गोमण्डलस्य ॥

(दृष्टानुपपत्तिपरिहाराधिकरणम्)

(९४५ न्यासान्तरवार्तिकम् ॥ ६ ॥)

॥ * ॥ प्रत्ययग्रहणं णियगर्थम् ॥ * ॥

(भाष्यम्) प्रत्ययग्रहणं कर्तव्यम् । पूर्ववत्प्रत्ययादिति वक्तव्यम् ॥ किं प्रयोजनम् ? । णियगर्थम् । णियगन्तादपि यथा स्यादिति । आकुसयते विकुसयते हृणीयते महीयते इति ॥

(प्रदीपः) प्रत्ययग्रहणमिति । यद्येवमतिप्रसङ्गः पणायति पनायतीति । तत्र केचिदाहुः—पूर्ववद् णियक्सन इति प्रत्ययविशेषा एव निर्देष्टव्याः ॥ अन्ये त्वाहुः—एवं पाठे भाष्यं वार्तिकं च न व्याख्यात भवतीति हेतुमण्णिचः प्रतिषेधः इत्यतिप्रसङ्गविषयोपलक्षणार्थं हेतुमण्णिज्ग्रहणम् ॥ ६२॥

(उद्द्योतः) वार्तिकं भाष्यं चेति । प्रत्ययग्रहणमिति वार्तिकं पूर्ववत्प्रत्ययादिति वक्तव्यमिति भाष्यं चासंगतं स्यादिति भावः ॥ आकुसादात्मनेपदिन इति गणसूत्रात्कुस आत्मनेपदी । हृणीङ्महीङौ कण्ड्वादी ङितौ पठितौ ॥

(न्यासान्तरं द्रढयितुमाक्षेपभाष्यम्)

तत्र को दोषः ? ।

(९४६ समाधानवार्तिकम् ॥ ७ ॥)

॥ * ॥ तत्र हेतुमण्णिचः प्रतिषेधः ॥ * ॥

(भाष्यम्) तत्र हेतुमण्णिचः प्रतिषेधो वक्तव्यः । आसयति शाययतीति ॥

(प्रत्ययग्रहणविकृतिदोषप्रदर्शकभाष्यम्)

सूत्रं च भिद्यते ॥

(सिद्धान्तिभाष्यम्)

यथान्यासमेवास्तु ॥

(आक्षेपभाष्यम्)

कथम्—आकुसयते विकुसयते हृणीयते महीयते इति ? ।

(समाधानभाष्यम्)

अनुबन्धकरणसामर्थ्याद्भविष्यति ॥

(उद्द्योतः) भाष्येऽनुबन्धकरणसामर्थ्यादिति । आकुसादात्मनेपदिन्नित्युक्तिसामर्थ्यादित्यपि बोध्यम् । यद्वा तस्याप्यात्मनेपदलिङ्गवन्तो बोध्या इत्यर्थ इति भावः ॥ इतरत्स्पष्टम् ॥ ६२ ॥

(समाधानान्तरभाष्यम्)

अथ वा—अवयवे कृतं लिङ्गं समुदायस्य विशेषकं भवति । तद्यथा—गोः सक्थनि कर्णे वा कृतं लिङ्गं समुदायस्य विशेषकं भवति ॥

(समाधानबाधकभाष्यम्)

यद्यवयवे कृतं लिङ्गं समुदायस्य विशेषकं भवति, हृणीययति महीययतीत्यत्रापि प्राप्नोति ॥

(समाधानसाधकभाष्यम्)

अवयवे कृतं लिङ्गं कस्य समुदायस्य विशेषकं भवति? यं समुदायं योऽवयवो न व्यभिचरति । यकं च न व्यभिचरति, णिचं तु व्यभिचरति । तद्यथा—गोः सक्थनि कर्णे वा कृतं लिङ्गं गोरेव विशेषकं भवति न गोमण्डलस्य ॥ पूर्ववत्सनः ॥६२

(१५२ आत्मनेपदनियमसूत्रम् ॥ १।३।२ आ० २३ सू०)

२१० आम्प्रत्ययवत्कृञोऽनुप्रयोगस्य ॥ १।३।६३ ॥

(कृञितिप्रत्याहाराश्रयणाधिकरणम्)

(आक्षेपभाष्यम्)

कृञ्ग्रहणं किमर्थम् ? ॥

(प्रदीपः) आम्प्रत्यय ॥६३॥ कृञ्ग्रहणमिति। कृञ एवानुप्रयोगो विहितो नान्यस्येति भावः ॥

(उद्द्योतः) आम्प्रत्ययवत् ॥ ६३ ॥ ननु तदभावेऽस्तिभूभ्यामपि स्यादत आह—कृञ एवेति ॥

(समाधानभाष्यम्)

इह मा भूत्—ईहामास ईहामासतुः ईहामासुः ॥

(आक्षेपभाष्यम्)

कथं चाप्रसक्तेरनुप्रयोगो भवति ? ॥

(समाधानभाष्यम्)

प्रत्याहारग्रहणं हि तत्र विज्ञायते ॥

(आक्षेपभाष्यम्)

कथं पुनर्विज्ञायते तत्र प्रत्याहारग्रहणमिति ? ॥

(समाधानभाष्यम्)

इह कृञ्ग्रहणात् ॥

(आक्षेपभाष्यम्)

इह कस्मात्प्रत्याहारग्रहणं न भवति ? ॥

(समाधानभाष्यम्)

इहैव कृञ्ग्रहणात् ॥

(आक्षेपभाष्यम्)

अथेह कस्मान्न भवति—उदुम्भाञ्चकार । उदुब्जाञ्चकार ? ।

(प्रदीपः) अथेह कस्मादिति । स्वरितञित इत्यनेनेति भावः ॥

(उद्द्योतः) स्वरितेति । कृञो ञित्त्वादिति भावः ॥

(आक्षेपबाधकभाष्यम्)

ननु च 'आम्प्रत्ययवद्' इत्युच्यते, न चात्राम्प्रत्ययादात्मनेपदं पश्यामः ॥

(उद्द्योतः) भाष्ये—आम्प्रत्ययादिति । बहुव्रीहिणाऽऽम्प्रत्ययप्रकृतेरित्यर्थः ॥

(आक्षेपसाधकभाष्यम्)

न ब्रूमोऽनेनेति । किं तर्हि ? । स्वरितञितः कर्त्रभिप्राये क्रियाफले आत्मनेपदं भवतीति ॥

(समाधानभाष्यम्)

नैष दोषः । इदं नियमार्थं भविष्यति आम्प्रत्ययवदेवेति ॥

(आक्षेपभाष्यम्)

यदि नियमार्थम्, विधिर्न प्रकल्पते—ईहांचक्रे ऊहांचक्रे इति ॥

(समाधानभाष्यम्)

विधिश्च प्रकृतः ॥ कथम् ? । पूर्ववदिति वर्तते । आम्प्रत्ययवत्पूर्ववच्चेति ॥ आम्प्रत्यय० ॥ ६३ ॥

(प्रदीपः) ननु संविधानेऽनेनात्मनेपदं विधीयते। यथा च यात्यादयः संविधाने न वर्तन्ते, तथोब्जादयोपि। तदर्थानुपाती च करोतिरप्यत्र विषये संविधाने न वर्तते इत्यात्मनेपदस्याप्रसङ्गः ॥ नैष दोषः । संविधान एवात्र विषये यदोब्जादयो वर्तन्ते शब्दशक्तिस्वाभाव्यात्तदर्थाभिव्यक्तये तदा करोतिः प्रयुज्यमानः संविधानविषय इति मत्वा चोद्यमुपन्यस्तम् ॥ परिहृतं च पूर्ववद्ग्रहणानुवृत्त्या वाक्यभेदेन । तत्रैकेन वाक्येन विधिः क्रियते, द्वितीयेन नियमः ॥ ६३ ॥

(उद्द्योतः) संविधानं, प्रयोजकव्यापारः। क्रियाफलस्य कर्तृगामित्वं वा ॥ यथेति। वक्ष्यमाणस्वरितञित इत्येतत्प्रत्याख्यानमभिप्रेत्येदम् । उपपादयिष्यते चेदं स्वरितञित इतिसूत्रे ॥ न वर्त्तते इति । अनभिधानादिति भावः ॥ सूत्रारम्भरीत्या समाधत्ते—नैष दोष इति । 'तदा तदर्थाभिव्यक्तय' इत्यन्वयः ॥ अनुवृत्तावपि कथमेकेन वाक्येनार्थद्वयावगतिरत आह—वाक्यभेदेनेति । आद्यस्य विधित्वम्, द्वितीयस्य पूर्ववदेवात्मनेपदं न त्वन्यथेति नियमार्थत्वमित्यर्थः । ईहांचक्रे इत्यत्राकर्तृगेपि क्रियाफले आत्मनेपदसिद्धिर्विधेः फलं बोध्यम् ॥ ६३ ॥

(१५३ आत्मनेपदनियमसूत्रम् ॥ १। ३। २ आ. २४ सू०)

२११ प्रोपाभ्यां युजेरयज्ञपात्रेषु ॥ १।३।६४ ॥

(९४७ आक्षेपवार्तिकम् ॥ १ ॥)

[॥ * ॥ स्वराद्युपसृष्टात् ॥ * ॥]

(भाष्यम्) स्वराद्युपसृष्टादिति वक्तव्यम् । उद्युङ्क्ते । अनुयुङ्क्ते ॥

(भाष्यम्) अपर आह—

(न्यासान्तरम्)

[॥ * ॥ स्वराद्यन्तोपसृष्टात् ॥ * ॥]

(भाष्यम्) स्वराद्यन्तोपसृष्टादिति वक्तव्यम् ॥ प्रयुङ्क्ते । नियुङ्क्ते। विनियुङ्क्ते । प्रोपाभ्याम् ॥ ६४ ॥

(प्रदीपः) प्रोपाभ्याम् ॥ ६४ ॥ स्वराद्यन्तोपसृष्टादिति । सम्निस्दुरित्येतान्निरस्य सर्वे उपसर्गाः संगृहीताः ॥ ६४ ॥

(उद्द्योतः) प्रोपाभ्याम् ॥ ६४ ॥ स्वराद्यन्तोपसृष्टादित्युक्त्वा प्रविनय उदाहृतास्तत्कथमत आह—सम्निस्दुरिति । स्वरादेः स्वरान्ताच्चेत्यर्थ इति भावः ॥ ६४ ॥

(१५४ आत्मनेपदनियमसूत्रम् ॥ १।३ ।२ आ० २५ सू०)

२१२ समः क्ष्णुवः ॥ १।३।६५ ॥

(आक्षेपभाष्यम्)

किमर्थं विदेशस्थस्य ग्रहणं क्रियते, न 'समो गमादिष्वि'त्येवोच्येत ? ॥

(९४८ समाधानवार्तिकम् ॥ १ ॥)

॥ * ॥ समः क्ष्णुवः सकर्मकार्थम् ॥ * ॥

(भाष्यम्) सकर्मकार्थोयमारम्भः । अकर्मकादिति तत्रानुवर्तते ॥ समः ॥ ६५ ॥

(१५५ आत्मनेपदनियमसूत्रम् ॥ १ ।३ ।२ आ. २६ सू०)

२१३ भुजोनवने ॥ १।३।६६ ॥

(९४९ आक्षेपवार्तिकम् ॥ १ ॥)

[॥ * ॥ अनवनकौटिल्ययोः ॥ * ॥]

(भाष्यम्) अनवनकौटिल्ययोरिति वक्तव्यम् । इहापि यथा स्यात्—प्रभुजति वाससी निभुजति जानुशिरसी इति ॥

(उद्द्योतः) भुजो ॥ ६६ ॥ भाष्ये—निभुजति जानुशिरसी इति । प्रतिमाया प्रति क्षेपः । अतः प्राप्यन्तस्याभावात्तैकवत्त्वम् ॥

(तृतीयाक्षेपभाष्यम्)

तत्तर्हि वक्तव्यम् ।

(सिद्धान्तिसमाधानभाष्यम्)

न वक्तव्यम् । यस्य भुजेरवनमनवनं सार्थस्तस्य ग्रहणम् । न चास्य भुजेरवनमनवनं चार्थः ॥ भुजोनवने ॥ ६६ ॥

(प्रदीपः) भुजोनवने ॥ ६६ ॥ यस्य भुजेरिति । संसर्गवद्विप्रयोगोपि हि विशेषस्मृतिहेतुः । यथा गोगृष्टीपर्यायो धेनुशब्द उपादीयमानः संसर्गिभिर्विशेषेवस्थाप्यते—सवत्सा धेनुर्धेनुरानीयतां सकिशोरा सकरभा सवर्करेति । एवमवत्सा अकिशोरा अकरभा अवर्करेति विशिष्टैव धेनुः प्रतीयते । यस्या येन दृष्टः संसर्गः सैव तद्रहितानीयते ॥ ६६ ॥

(उद्द्योतः) अवननिषेधेनाभ्यवहारस्येवेति कथं लभ्यमत आह—संसर्गवदिति ॥ सवर्करेति । धेनुशब्दस्य धात्वर्थत्वमेव प्रवृत्तिनिमित्तं न तु गोत्वसमानाधिकरणमेव तद्धिति भावः ॥ ६६ ॥

(१५६ आत्मनेपदनियमसूत्रम् ॥ १।३।२ आ. २७ सू०)

२१४ णेरणौ यत्कर्म णौ चेत्स कर्तानाध्याने ॥ १।३।६७ ॥

(अणिकर्मण एव णौ कर्मत्वविवक्षाधिकरणम्)

(९५० आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ णेरात्मनेपदविधानेऽण्यन्तस्य कर्मणस्तत्रोपलब्धिः ॥ * ॥

(भाष्यम्) णेरात्मनेपदविधानेऽण्यन्तस्य यत्कर्म यदा ण्यन्ते तदेव कर्म भवति तदा आत्मनेपदं भवतीति वक्तव्यम् ॥

(९५१ आक्षेपसाधकवार्तिकम् ॥ २ ॥)

॥ * ॥ इतरथा हि सर्वप्रसङ्गः ॥ * ॥

(भाष्यम्) इतरथा हि सर्वत्र प्रसङ्गः स्यात् । इहापि प्रसज्येत—आरोहन्ति हस्तिनं हस्तिपकाः, आरोहयमाणो हस्ती स्थलमारोहयति मनुष्यान् ॥

(प्रदीपः) णेरणौ ॥ ६७ ॥ एकस्मिन्वाक्ये कर्मान्तरनिवृत्तिरलभ्येति णेरिति वार्तिकारम्भः । एकवाक्यतायां त्वयमर्थः—ण्यन्तादात्मनेपदं भवति अण्यन्तावस्थायां यत्कर्म ण्यन्तावस्थायां यदि स कर्ता भवत्याध्यानादन्यत्रेति । भवति च कर्मान्तरसद्भावेप्यणौ कर्म णौ कर्ता ॥

(उद्द्योतः) णेरणौ ॥ ६७ ॥ अणौ कर्मणः कर्तृत्वस्य सूत्रकृतोक्तत्वात् कर्मान्तरनिवृत्तिपरत्वे वार्तिकतात्पर्यमाह—एकस्मिन्निति । अत एव वार्तिकव्याख्यानभाष्ये तदेवेति प्रयुक्तम् ॥ यस्त्वेतद्वार्तिकस्थकर्मपदानि क्रियापरत्वेन व्याचक्षते, तन्न । कर्तरि कर्मव्यतिहारे इतिसूत्रे क्रियाग्रहणं कर्तव्यमिति सूत्रकारं शिक्षयतो वार्तिककारस्य 'कर्मशब्दः क्रियापरः' इत्यर्थाज्ञानेन तद्भाष्यस्थकर्मपदानां क्रियापरत्वेन व्याख्यानस्यात्यन्तमनौचित्यात् । एवं च सूत्रकृतस्तदर्थसाधनपरभाष्यस्थकर्मपदानामपि तथा व्याख्यानमयुक्तमेवेति ध्येयम् ॥ भाष्ये—आरोहन्ति हस्तिनमिति । आरोहन्ति हस्तिनं हस्तिपकाः आरोहयमाणो हस्तीत्यत्र स्थलमारोहयति मनुष्यानित्यत्रापि स्यादित्यर्थः । मनुष्या हस्तिनमारोहन्तीत्यण्यन्तावस्था स्थलमिति चातिरिक्तं कर्मेति भावः । सौकर्यातिशयप्रतिपादनाय प्रेरणाप्रकृतिवत् तत्प्रतिपादनायैव स्थलविषयमप्यवधकत्वरूपकर्मत्वेनाश्रित्य द्विकर्मकत्वकरणम् । एवं च न्यग्भवनारोहणोभयानुकूलव्यापारो धात्वर्थः । स्थलं न्यग्भावयन् मनुष्यानारोहयतीत्यर्थः । स्थलशब्देन न गजपृष्ठस्थं कर्मप्रत्युपवेशस्थानमुच्यते ॥ हस्तीति मध्यमणिन्यायेनोभयान्वयि ॥

(तदस्याक्षेपभाष्यम्)

तत्तर्हि वक्तव्यम ॥

(सिद्धान्तिसमाधानभाष्यम्)

न वक्तव्यम् । एवं वक्ष्यामि—"णेः" आत्मनेपदं भवति । ततः "अणौ यत्कर्म णौ चेत्" अण्यन्ते यत्कर्म णौ चेत् णौ यदि तदेव कर्म भवति । ततः "स कर्ता" कर्ता चेत्स भवति णाविति ॥

(प्रदीपः) भाष्यकारस्तु वाक्यभेदाश्रयेणैतमर्थं साधयति—**णेरात्मनेपदं भवती**त्येकं वाक्यम् । ततो**ऽणौ यत्कर्म णौ चे**दिति द्वितीयम् । अत्र वाक्ये यत्तदोर्नित्यसंबन्धाद्यच्छब्देन तच्छब्द आक्षिप्यते । धर्मान्तरस्य चानिर्देशात्कर्मत्वमेव संनिधानात्प्रतिनिर्दिश्यते । **अणौ यत्कर्म णौ चेत्तत्कर्मे**ति प्रतिनिर्देशेन च कर्मान्तरव्यावृत्तिः क्रियते, न त्वणौ कर्मणो णौ कर्मत्वसद्भावः प्रतिपाद्यते **स कर्ते**ति वाक्यान्तरेण तस्य कर्तृत्वप्रतिपादनात् युगपदेकक्रियापेक्षया कर्मत्वकर्तृत्वविरोधादेकस्य । यथेष्टं वाक्यशेषपरिकल्पनादणौ यत्कर्म णौ चेत्तदेव कर्मेत्येवकाराध्याहारात्कर्मान्तरनिवृत्तिलाभः। ततः **स कर्ते**ति तृतीयं वाक्यमणौ कर्मणो णौ कर्तृत्वप्रतिपादनपरम् । एवमेषां वाक्यानामेकवाक्यत्वे महावाक्यं लक्ष्यसंस्कारकं संपद्यते ॥

(उद्योतः) **प्रतिनिर्दिश्यत इति** । विधीयते इत्यर्थः । कर्मशब्दश्चात्रोत्तरवाक्यवत् कारकपर एवेति भावः ॥ एवमपि कर्मान्तरनिवृत्तिः कथमित्यत आह—**स कर्त्तेति** ॥ कर्तृत्वप्रतिपादनेपि कर्मत्वं किं न स्यादत आह—**युगपदिति** । न चैकस्यैकदैव व्यापारव्यधिकरणफलाश्रयत्वं व्यापाराश्रयत्वं च सम्भवतीति भावः ॥ **यथेष्टमिति** । शास्त्रस्य बहुलक्ष्यसंस्कारकत्वानुरोधेनेत्यर्थः । एतेनाणौ द्विकर्मका एवास्योदाहरणमित्यपास्तम् । अण्यन्तावस्थास्वकर्मत्वावच्छेदेन कर्तृत्वप्रतिपादनात् । इदमेव ध्वनयितुं भाष्ये दृष्टान्तव्याजेन सूत्रोदाहरणं दर्शितम् ॥

(सूत्रप्रत्याख्यानाधिकरणम्)

(सूत्रप्रत्याख्यानभाष्यम्)

यद्येवं कर्मकर्ताऽयं भवति । तत्र कर्मकर्तृत्वात्सिद्धम् ॥

(प्रदीपः) **यद्येवमिति** । यथा लुनाति केदारं देवदत्तः, लूयते केदारः स्वयमेवेति केदारः कर्मकर्ता, तथा ण्यन्तेपि भवति—लावयते केदारः स्वयमेवेति ॥ कथमिति चेत् । उच्यते—लुनातिस्तावद्द्विधाभवनोपसर्जने द्विधाभावने वर्तते । लुनाति केदारं देवदत्तः । द्विधाभवन्तं द्विधा भावयतीत्यर्थः । यदा तु केदारस्य सौकर्यातिशयविवक्षायां देवदत्तस्य व्यापारो न विवक्ष्यते तदा द्विधाभवनमात्रे लुनातिर्वर्तते अनेकार्थत्वाद्धातूनाम् । भिन्ना एव वा धातवो भिन्नार्थाः । सारूप्यात्तु तत्त्वाध्यवसायः । तत्र द्विधाभवने केदारस्य कर्तुः **कर्मवत्कर्मणा तुल्यक्रिय** इति कर्मकार्याण्यतिदिश्यन्ते । तेन लूयते केदारः स्वयमेवेत्यादयः प्रयोगा उपपद्यन्ते । अत्रापि स्वयमित्यस्य यदा आत्मनेत्यर्थस्तदा आत्मापेक्षया कर्मत्वमस्त्येवेति लूयते केदार इत्येतावदुदाहार्यम् ॥ वृत्तिकाराणां तु स्वयमिति वचनं कर्त्रन्तरव्युदासपरं विज्ञेयम् । अथ वा स्वयमित्यनेन करणत्वमात्मनः प्रतिपाद्यते, न तु कर्तृत्वम् । ततो यदा द्विधाभवनवृत्तेर्लुनातेर्देवदत्तादिप्रयोजकव्यापारे णिजुत्पद्यते तदा य एवार्थो लुनाति केदारं देवदत्त इति, स एवार्थो लावयति केदारं देवदत्त इति । पुनः केदारस्य सौकर्यातिशयविवक्षायामविवक्षिते देवदत्तस्य व्यापारे द्विधाभवनमात्रवृत्तिर्लावयतिः सम्पद्यते । ततश्च य एवार्थो लूयते केदारः स्वयमेवेति, स एव लावयते केदारः स्वयमेवेति । न च प्रयोज्यप्रयोजकभावनिवृत्तौ णिचो निवृत्तिः, उपायनिवृत्तावप्युपेयानिवर्तनात् । सिद्धशब्दव्युत्पत्तये हि प्रकृतिप्रत्ययविभागकल्पना आश्रीयते, अर्थस्योपादानं त्यागश्च क्रियते । लौकिके तु व्यवहारे सौकर्यमात्रविवक्षायां लावयते केदार इति प्रयुज्यते । एवं तावत्

"निवृत्तप्रेषणाद्धातोः प्राकृतेर्थे णिजुच्यते ।

इत्येतत्पक्षाश्रयेण कर्मकर्ता व्याख्यातः ॥ अपरः कल्पः—लुनाति केदारं देवदत्तः । लुनन्तं देवदत्तं सौकर्यातिशयात्केदारः प्रयुङ्क्ते इति केदारव्यापारे णिजुत्पद्यते—लावयति केदारो देवदत्तेनेति । पुनः प्रयोज्यप्रयोजकभावाविवक्षायां लावयते केदारः स्वयमेवेति प्रयुज्यते । तत्र पूर्वप्रक्रियाश्रयणे **कर्मवत्कर्मणा तुल्यक्रिय** इति सिद्धमात्मनेपदम् । तथा हि—लावयति केदारं देवदत्त इत्यत्र यस्मिंल्लावयतौ धातौ यादृशी कर्मावस्थायां केदारस्य द्विधाभवनलक्षणा क्रिया तस्मिन्नेव धातौ तादृशी कर्त्रवस्थायामिति सिद्धं लावयते केदारः स्वयमेवेति । द्वितीया तु प्रक्रिया सूत्रे एतस्मिन्नारब्धे सम्भवतीति प्रदर्शिता । न तु तस्यां कर्मवद्भावः प्राप्नोति । लावयतौ केदारस्य कर्मत्वाभावात् कर्मणा समानधातौ तुल्यक्रियत्वाभावात् ॥

(उद्योतः) एवं चाकर्मकाणामेतत्सूत्रोदाहरणत्वं फलितं तद्ध्वनयन्नाह—भाष्ये—**यद्येवमिति । कर्मकर्तृत्वात्सिद्धमिति । च** ॥ नन्विदमनुपपन्नं, समानधातौ कर्मस्थक्रियया तुल्यक्रियाकर्तुः कर्मवद्भावो, न चात्र तथा । तथाहि लावयत इत्यत्र किं लुनातिकर्मणा समानक्रियत्वम्, उत लावयतिकर्मणा । नाद्यः । ण्यन्ताण्यन्तत्वेन धातुभेदात् ॥ नान्त्यः । लुनातेर्णिचि लावयति केदारं देवदत्तेन यज्ञदत्त इत्यत्र केदारस्य प्रकृत्यंशकर्मत्वेन तथैव धातुभेदात् । लवनकर्तुस्तु गत्यादिनियमात्कर्मत्वमेव नेत्यत आह—**यथा लुनातीति** । दृष्टान्तमुपपादयति—**लुनातिस्तावदिति** । सौकर्यातिशयोऽनायासेन द्विधाभवनाश्रयत्वम् तच्च कर्तृव्यापारस्येषत्त्वेन कर्तृव्यापाराविवक्षायामप्यनुदरा कन्येतिवत्तत्र पर्यवसानम् । ईषत्त्वादेव तस्य स्वातन्त्र्येण धात्ववाच्यतेति द्विधाभवनमात्रवृत्तित्वं लुनातेर्बोध्यम् ॥ क्वचित्फलव्यापारयोः शक्तिः, क्वचित्फले इति कथमत आह—**अनेकार्थत्वादिति** । तदुक्तम्—

"एकदेशे समूहे च व्यापाराणां पचादयः ।
स्वभावतः प्रवर्तन्ते तुल्यरूपसमन्विताः" इति ॥

केचिदर्थभेदाच्छब्दभेदमिच्छन्ति तन्मतेप्याह—**भिन्ना एवेति** ॥ नन्वेवं धातुभेदात् कर्मवद्भावो न स्यादत आह—**सारूप्यादिति** ॥ तदुक्तम्—

"तानि धात्वन्तराण्येव पचिं सिध्यतिवद्विदुः ॥
भेदेपि तुल्यरूपत्वादेकत्वपरिकल्पना" इति ॥

नन्वेवं केदारः कर्तैवेति कथमयं कर्मकर्तेत्यत आह—**तत्रेति** । आतिदेशिकस्तथा व्यवहार इति भावः ॥ इयं च द्वितीयावस्था । यावतीषु सोपानस्थानीयास्वर्थविभागभूमिषु पदं विन्यस्येयं प्रायोगिकी पर्यन्तभूमिः प्राप्यते ता अन्तरालभाविन्यो गम्यमाना भूमयोऽवस्थाशब्देनोच्यन्ते॥ तत्र प्रथमं द्विधाभवनं बुद्धिरवगाहते । द्विधाभवनेस्य स्वरूपयोग्यतां ज्ञात्वैव कर्तुर्द्विधाभावने प्रवृत्तेः । अन्यथा शिलायामङ्कुरोत्पादनायेवाप्रवृत्तिप्रसङ्गात् । ततो द्विधाभावने कर्मतापर्यवगाहनम् । ततोऽत्यन्तसौकर्याय नानेन प्रयुक्तः सन् द्विधा भवति, किं तु स्वत एवेति परप्रेरणाऽसंवलितद्विधाभवनलक्षणस्वातन्त्र्यावगाहनमिति द्विधाभवनमात्रवृत्तित्वे कर्मवद्भावः । स्पष्टं चेदं हेलाराजीयादौ ॥ विशिष्टवाचको धातुर्विशेषणे पर्यवसन्न इति । इमां द्वितीयकक्ष्यात्वेन व्यवहरन्ति ॥ दृष्टान्तमुपपाद्य ण्यन्ते उपपादयति—**ततो यदेति** । तत्र लुनाति केदारमिति कक्ष्यापेक्षयाऽस्यां कक्ष्यायां णिच् विशेषः, तस्यां द्विधाभवनस्वरूपयोग्यतामात्रनिश्चयेन द्विधाभवनरूपे तत्प्रयोजकव्यापारे प्रवृत्तिः, अस्यां तु द्विधाभवने स्वत एव प्रवृत्तं दृष्ट्वा तत्क्षेमाय कर्तॄणां प्रवृत्तिरिति वक्ष्यमाणसौकर्यप्रतीतिलक्षणविच्छित्तिविशेषलिप्सया णिजुपादानम् ॥ **सौकर्यातिशयेति** । अस्यां तु कक्षायां स्वतःप्रवृत्तस्तत्क्षेमायापि न प्रयोजकव्यापारमपेक्षत इति सौकर्यातिशयविवक्षया प्रयोक्तृव्यापाराविवक्षेति भावः ॥ इयं प्रायोगिकी पञ्चमी पर्यन्तभूमिः ॥ तदुक्तम्—

"अवस्थां पञ्चमीं प्राहुर्ण्यन्ते तां कर्मकर्तरि" इति ॥

तस्याः पञ्चमीत्वं चैवम् । तत्र द्वितीयकक्षायां फलसमानाधिकरणो व्यापारोऽर्थस्ततो णिचि तृतीया कक्षा । ततो णिजर्थव्यापारस्य प्रकृत्यर्थस्य फलसमानाधिकरणव्यापारस्य च त्यागे चतुर्थी कक्ष्या । ततः फलसमानाधिकरणे व्यापारे प्रवर्तनात्वेन विवक्षित णिच्युदाहरणभूतायाः पञ्चमीत्वम् । उभयत्रापि णिज्निर्वाहाय सर्वान्ते हरिणा **निवृत्तप्रेषणादित्युक्तं** । तदाह—**उपायनिवृत्तावपीति** । मुख्यप्रयोजकव्यापारनिवृत्तावपि स्वव्यापारे एव तत्त्वारोपात्तदनिवृत्तिरिति भावः ॥ एतच्च शब्देन्दुशेखरे विस्तरेण निरूपितम् ॥ तदाह—**सिद्धशब्देति** । ननु लूयते केदार इति प्रयोगे सति किमर्थं णिच्प्रत्ययघटितप्रयोगादरोऽत आह—**सौकर्येति** । लूयते केदार इति कक्षायां स्वत एव प्रयोज्यस्य स्वव्यापारे प्रवृत्तिरिति सौकर्यप्रतीतिमात्रं, पञ्चम्यां तु क्षेमार्थमपि प्रयोजकव्यापारो नापेक्षित इति तदतिशयस्य लाभादेतदादर इति भावः ॥ **प्राकृते** । प्रयोगान्तरे प्रकृतिवाच्ये व्यापारे ॥ अध्यारोपितप्रेषणपक्षमाह—**अपर इति** । **लुनन्तमिति** । स्वयं द्विधाभवने प्रवृत्तं केदारं लविता क्षेमाय प्रयुङ्क्ते इति निवृत्तप्रेषणे चतुर्थी कक्षा, इह तु स्वत एव द्विधाभवने प्रवृत्त इत्येतावदेव न, किं तु प्रत्युत स एव लवितारं प्रयुङ्क्ते इति प्रयोज्यत्वाभिमतस्य प्रयोजकत्वेनाधिकः सौकर्यातिशय इति भावः । **लावयति केदारो देवदत्तेनेति** । अत्र लावयतीति पाठस्तु लेखकप्रमादाद् ग्रन्थकृद्वक्ष्यमाणसिद्धान्तरीत्याऽनेनात्मनेपदप्राप्तेः ॥ यद्वाऽकर्मकाण्येवोदाहरणानीति मन्यमानस्यात्रत्यपूर्वपक्षिणो मतेऽनुपदवक्ष्यमाणरीत्या कर्मवद्भावाप्राप्त्या तथोक्तिः ॥ नन्वेवमत्रैव कर्मवद्भावाप्राप्तिविषयेऽस्य सूत्रस्यावश्यकत्वेन कथं कर्मवद्भावात् सिद्धमित्युक्तिरिति चेन्न । अत्रत्यकर्मपदस्य कर्मसंज्ञायोग्यार्थपरत्वेन तदतिरिक्तस्य देवदत्तरूपस्य फलाश्रयस्य सत्त्वेनैतदप्राप्तेः । कर्मसंज्ञा तु गतिबुद्धीतिनियमान्नेत्यन्यत् । कर्तृकर्मेतरकर्माभाव इतिवक्ष्यमाणसिद्धान्तरीत्या त्वात्मनेपदं भवत्येवेति दिक् ॥ **पुनरिति** । देवदत्ते प्रयोज्यत्वस्याविवक्षायां केदारे तन्निरूपितप्रयोजकत्वस्याप्यप्रतीतौ देवदत्तव्यापारस्याप्यप्रतीतेर्द्विधाभवनमात्रे लावयतिरिति भावः ॥ स्थलमारोहयति मनुष्यानिति प्रत्युदाहरणेनायमपि प्रकारो भाष्यकृता ध्वनितः ॥ **प्रदर्शितेति** । इयादिभिरिति शेषः । न तु तत्रापि कर्मवद्भावविषयत्वे तत्तात्पर्यमिति भावः ॥ एवं चाध्यारोपितप्रेषणपक्षाश्रानेनाश्रायं पूर्वपक्ष इति ध्वनितम् ॥ वस्तुतो निवृत्तप्रेषणतृतीयकक्षामादाय तत्संभवः । द्विधाभवनानुकूलव्यापाररूपार्थोपस्थितौ तत्प्रतिपादकण्यन्ताण्यन्तयोर्द्वयोरपि शब्दयोरुपस्थित्यविशेषात् समानधातौ कर्मणा तुल्यक्रियत्वस्य ज्ञानसत्त्वात् । न चैवं लावयति केदारो देवदत्तेनेति द्वितीयकक्षायामपि कर्मवद्भावापत्तिः । व्यापारव्यधिकरणफलवाचकानां नेत्यर्थकसकर्मकाणां प्रतिषेध इति वचनेन तदप्राप्तेरिति दिक् ॥ परे तु तत्र पक्षे द्वितीयकक्षैवोदाहरणं वक्ष्यमाणसिद्धान्तरीत्या तद्ध्वनयन्नाह—न तु तस्यामितीत्याहुः ॥

(१५२ सूत्रारम्भसाधकवार्तिकम् ॥ ३ ॥)

॥ * ॥ कर्मकर्तृत्वात्सिद्धमिति चेद्यक्चिणोर्निवृत्त्यर्थं वचनम् ॥ * ॥

(भाष्यम्) **कर्मकर्तृत्वात्सिद्धमिति चेद् यक्चिणोर्निवृत्त्यर्थमिदं वक्तव्यम् । कर्मोपदिष्टौ यक्चिणौ मा भूतामिति ॥**

(प्रदीपः) **यक्चिणोर्निवृत्त्यर्थमिति** । अणौ यत्कर्म णौ चेत्स कर्ता तदा णेरात्मनेपदमेव नान्यदिति नियमार्थमेतदित्यर्थः ॥

(उद्द्योतः) भाष्ये—**यक्चिणोर्निवृत्त्यर्थमिति** । नियमस्य सजातीयापेक्षत्वेन प्रत्ययान्तरस्यैव वारणाच्चिण्वदिण्निवृत्त्यर्थमिति नोक्तम् ॥

(१५३ सूत्रारम्भबाधकवार्तिकम् ॥ ४ ॥)

॥ * ॥ न वा यक्चिणोः प्रतिषेधात् ॥ * ॥

(भाष्यम्) **न वा एष दोषः ॥ किं कारणम् ? ।**

यक्चिणोः प्रतिषेधात् । प्रतिषिद्ध्येते अत्र यक्चिणौ *यक्चिणोः प्रतिषेधे हेतुमण्णिश्रिब्रूञामुपसंख्यानम्* इति ॥

(उद्द्योतः) एष दोष इति । यद्दोषपरिहाराय त्वया नियमार्थत्वं व्याख्यायते स यक्चिणप्राप्तिरूपो दोषो नेत्यर्थः । एवं चायुक्तं नियमार्थत्वमिति भावः ॥

(सूत्रारम्भसाधकभाष्यम्)

यस्तर्हि न हेतुमण्णिच्, तदर्थमिदं वक्तव्यम् । तस्य कर्मापदिष्टौ यक्चिणौ मा भूतामिति । उदपुपुच्छत पुच्छं स्वयमेव ॥

(प्रदीपः) उदपुपुच्छत पुच्छमिति ॥ कथं पुनरत्राणौ कर्म विद्यते यावता पुच्छशब्दो द्रव्यवचनः ॥ अत्राहुः— अस्मिन्नेव विषये पुच्छशब्दः पुच्छकर्मिकायामुदसनक्रियायां वर्तते । तस्मात् स्वार्थे णिङ् प्रत्ययः । ततो यदा भ्राम्यमाणं पुच्छं संस्कारवशाच्चक्रमिव भ्रमणक्रियायां भूतायां स्वातन्त्र्येण विवक्ष्यते तदा उदपुपुच्छतेत्यात्मनेपदमेव णिङन्ताद् यथा स्यादित्येवमर्थमिदं सूत्रं संपद्यते ॥

(उद्द्योतः) यावतेति । एवं चाण्यन्तपुच्छशब्दस्य क्रियावचनत्वाभावेन तत्र कर्माभाव इति क्रियमाणेपि सूत्रे यगादिनिवृत्तिर्न प्राप्नोति, अनेन नियमस्य प्राप्त्यभावादिति भावः ॥ उदसनक्रियायामिति । यद्यपि णिङुपसंदान एव पुच्छपदं तत्समवेतक्रियापरं न केवलमित्यण्यन्तप्रयोगो दुर्लभस्तथापि शास्त्रदृष्ट्या कर्मवानण्यन्तोस्तीत्यभिमानः ॥ भूतायामित्यनेन लुङ्विषयप्रदर्शनम् ॥ केचित्तु णिङन्ताण्णिचीदमुदाहरणमित्याहुः । तन्न । यस्तर्हि न हेतुमण्णिजितिभाष्यासंगतेः ॥

(सूत्रारम्भबाधकभाष्यम्)

अत्रापि यथा भारद्वाजीयाः पठन्ति तथा भवितव्यं प्रतिषेधेन *यक्चिणोः प्रतिषेधे णिश्रन्थिग्रन्थिब्रूञात्मनेपदाकर्मकाणामुपसंख्यानम्* इति ।

(उद्द्योतः) भाष्ये—अत्रापि यथा भारद्वाजीया इति । एवं च तेनैव नियमफलसिद्धेरनर्थकं सूत्रमिति भावः ॥

(प्रतिषेधावश्यकताभाष्यम्)

स चावश्यं प्रतिषेध आश्रयितव्यः ।

(९५४ अन्यथानुपपत्तिवार्तिकम् ॥ ५ ॥)

॥ * ॥ इतरथा हि यत्र नियमस्ततोन्यत्र प्रतिषेधः ॥ * ॥

(भाष्यम्) अनुच्यमाने ह्येतस्मिन्यत्र नियमस्ततोन्यत्र तेन यक्चिणोः प्रतिषेधो वक्तव्यः स्यात् । गणयति गणं गोपालकः। गणयति गणः स्वयमेव ॥

(प्रदीपः) गणयति गणइति । गणो णावेव कर्म नाणावेव कर्तृत्वस्य नियमस्याव्यापाराण्णिश्रन्थिग्रन्थीतिवक्तव्य एव प्रतिषेधः । तस्यैव च व्यापकत्वान्नार्थोनेन सूत्रेणेत्यर्थः ॥ कथं पुनरत्र कर्मवद्भावप्राप्तिः । यावता कर्मस्थभावकानां कर्मस्थक्रियाणां च कर्मवद्भावो विधीयते । गणनं च संख्यानिमित्तकः परिच्छेदो ज्ञानविशेषः कर्तरि वर्तते ॥ नैष दोषः । भागशो ऽवस्थापनेपि गणिर्वर्तते । भागशोवतिष्ठमानं गणं गोपालकोऽवस्थापयति । तत्रानुकूलत्वाद्गणस्यैव कर्तृत्वविवक्षायामस्ति कर्मस्थभावकत्वात्कर्मवद्भावः ॥

(उद्द्योतः) ननु सूत्रेणैव सिद्धे वार्तिके णिग्रहणमेव न कार्यमित्यत आह—भाष्ये—स चावश्यमिति । अनुच्यमाने इति । णिग्रहण इति शेषः ॥ यत्र नियमोऽण्यन्ताद्ण्यन्तस्थले ॥ ततोन्यत्रेति । ण्यन्तैकविषये गणयति गण इत्यादौ ॥ प्रतिषेध इति । सूत्रेणासिद्धेर्वार्तिके णिग्रहणाभावाच्चान्यदेव किंचिद्वचनं तेन वादिना कार्यम् । ततो वरं वार्तिक एव णिग्रहणमिति भावः । गणयतीत्यत्र सकर्मकाकर्मकावस्थयोरुभयत्रापि स्वार्थणिजेवेति बोध्यम् ॥ कथं पुनरिति । एवं च यक्चिणोः प्राप्त्यभावात्प्रतिषेधो व्यर्थ इति भावः ॥ भागश इति । भागशोऽवस्थानं च कर्मस्थमिति भावः ॥

(९५५ अन्यथानुपपत्तिशेषवार्तिकम् ॥ ६ ॥)

॥ * ॥ आत्मनेपदस्य च ॥ * ॥

(भाष्यम्) आत्मनेपदस्य च प्रतिषेधो वक्तव्यः। गणयति गणः स्वयमेव ॥

(उद्द्योतः) भाष्ये—आत्मनेपदस्य चेति । न केवलं यक्चिणोरेवात्मनेपदस्यापीत्यर्थः ॥

(९५६ सूत्रारम्भसाधकवार्तिकम् ॥ ७ ॥)

॥ * ॥ आत्मनेपदप्रतिषेधार्थं तु ॥ * ॥

(भाष्यम्) आत्मनेपदप्रतिषेधार्थमिदं वक्तव्यम्। गणयति गणः स्वयमेव ॥

(प्रदीपः) आत्मनेपदप्रतिषेधार्थमिति । अणौ कर्मणो णौ कर्तृत्वे आत्मनेपदं यथा स्याद्, णौ तु कर्मणो णौ कर्तृत्वे मा भूदित्येवमर्थमिदमित्यर्थः ॥

(उद्द्योतः) तर्हि तदर्थमेवेदं सूत्रमस्त्वित्याह—आत्मनेपदप्रतिषेधार्थं त्विति ॥ कर्मवद्भावेन सर्वत्रात्मनेपदे सिद्धे इदं सूत्रं ण्यन्तानामण्यन्तकर्मतुल्यक्रिये कर्तर्येवात्मनेपदं न तु ण्यन्तकर्मतुल्यक्रिय इति नित्यण्यन्तेभ्यः कर्मकर्तरि तन्निवृत्त्यर्थमित्यर्थः ॥ ननु सिद्धस्य पुनर्वचनमन्यनिवृत्त्यर्थं स्यान्न तत्प्रतिषेधार्थमत आह— अणौ कर्मण इति । सिद्धकार्यायाः प्रकृतेरुपादानं प्रकृत्यन्तरनिवृत्त्यर्थमिति भावः ॥ विशेषणान्तरस्य त्वेतद्व्यावृत्तिमात्रफलकत्वे नोपयोग इति तन्नोक्तम् । उपलक्षणत्वं वा बोध्यम् ।

(प्रत्याख्यानसाधकभाष्यम्)

इष्यत एवात्मनेपदम् ॥

(उद्द्योतः) भाष्ये—इष्यत एवेति। कर्मवद्भावेनेत्यर्थः॥ एवं चेष्टव्यावर्तकता सूत्रस्य नोचितेति भावः॥ एवं च गणयते गण इत्येव रूपं तन्त्रेति तात्पर्यम्॥

(आक्षेपभाष्यम्)

किमिष्यत एव, आहोस्वित्प्राप्नोत्यपि?॥

(उद्द्योतः) ननु णेरणाविति नियमसूत्रादप्राप्तौ निर्णीतायां कथमिष्यत इत्युक्तिरिति शङ्कते—**किमिष्यतएवेति**॥

(समाधानभाष्यम्)

इष्यते च, प्राप्नोति च॥ कथम्?। अणाविति कस्येदं णेर्ग्रहणं यस्माण्णेः प्राक्कर्म वा कर्ता वा विद्यते। न चैतस्माण्णेः प्राक्कर्म कर्ता वा विद्यते॥

(प्रदीपः) **न चैतस्मादिति**। नित्यत्वाण्णिचः केवलानां चुरादीनां प्रयोगाभावादणौ कर्मणोऽसंभवाण्णेरिति हेतुमण्णिचो ग्रहणम्। प्रतिषेधोप्यणाविति तस्यैव प्रत्यासत्त्या न्याय्य इत्यहेतुमण्णौ गणस्य कर्मत्वं हेतुमण्णौ कर्तृत्वमिति सूत्रस्यायं विषयो भवत्येवेति कथमत्रानेनात्मनेपदं निवार्येतेत्यर्थः॥

(उद्द्योतः) सूत्रकारस्यापीदमिष्टमित्याह—**इष्यते चेत्यादि**॥ नियमसत्त्वात् कथं प्राप्तिरिति शङ्कते—**कथमिति**। नियमस्यैवाप्राप्तिरित्युत्तरम्॥ **न चैतस्मादिति**। चुरादिणिच इत्यर्थः॥ ननु णिजुत्पत्तेः पूर्वं धातोर्वर्तमानत्वे कर्मणोपि संभवादाह—**नित्येति**॥ एवं च ततः प्रागवस्थायां प्रयोगस्यैवाभावेन कर्ता च कर्म चास्य नास्तीत्यर्थः॥ **कर्त्रेति**। दृष्टान्तार्थम्॥ फलान्तरमप्यस्य वक्ष्यते तदाह—**अणौ कर्मणोऽसंभवादिति**। अस्य 'कथमत्रात्मनेपदं वार्येत' इत्यनेनान्वयः। नियमप्राप्तेः। गणयति गण इत्युदाहरणस्यावस्थाद्वयेपि चुरादिण्यन्तस्यैव प्रक्रमात्॥ चुरादिण्यन्तप्रकृतिकहेतुमण्ण्यन्तत्वे त्वेतत्सूत्रविषयतया पूर्वपक्षिणोपि तत्रात्मनेपदस्येष्टतया तत्रानेन तन्निवारणमशक्यमिति स्वयमाह—**णेरितीत्यादि**। परं त्वेषोक्तिर्विफला, भाष्ये तत्प्रक्रमाभावात्॥ चिति स्मृत्यामित्यादि इदित्करणादनित्यण्यन्तत्वस्य चुरादीनां ज्ञापनेपि तद्विशेषविषयमिति बोध्यम्॥ वस्तुतस्तज्ज्ञापकमेव चिन्त्यम्। कुद्रिप्रभृतीनामिव तस्यापीदित्त्वस्योच्चारणमात्रार्थत्वात्। केवलं घुषेरविशब्दने इति लिङ्गादनित्यण्यन्तत्वं भाष्यकृद्वक्ष्यति॥ यद्यप्याधृषाद्वेति विकल्पितणिचोपि चुरादौ सन्ति तथाप्यणावकर्मकादित्यत्र हेतुमण्णिच एव ग्रहणसंभवादिहापि साजात्यात्साहचर्याच्च तथैवोचितमिति तत्त्वम्॥

(सूत्रसाधकभाष्यम्)

इदं तर्हि प्रयोजनम्—अनाध्यान इति वक्ष्यामीति॥ इह मा भूत्—स्मरति वनगुल्मस्य कोकिलः। स्मरयत्येनं वनगुल्मः स्वयमेवेति॥

(प्रदीपः) **इदं तर्हीति**। न चानिर्दिष्टविषयः प्रतिषेधः शक्यते विधातुमिति सर्वमेव सूत्रं क्रियते॥ **वनगुल्मस्येति**। कर्मोपलक्षणमेतत्। अत्र हि वनगुल्मस्य शेषत्वेन विवक्षितत्वात्कर्मत्वाभावः। तस्मात् स्मरति वनगुल्ममिति प्रदर्शनीयम्॥ **स्मरयत्येनमिति**। एतदप्युपलक्षणम्। अत्रह्येनमिति कर्मणः सद्भावात् **कर्मवदकर्मकाणामिति** वचनात्कर्मवद्भावस्य प्राप्तिर्नास्ति। नाप्यनेनात्मनेपदस्य, कर्मान्तरसद्भावात्। तस्मात्स्मरयति वनगुल्मः स्वयमेवेति प्रदर्शनीयम्॥

(उद्द्योतः) ननु शेषवैयर्थ्यमत आह—**न चानिर्दिष्टेति**। यद्यपि प्रतियोगिभूतात्मनेपदनिर्देशेनापि प्रतिषेधः शक्यस्तथाप्यन्यांशानुक्तावाध्यानार्थात्कदापि तन्न स्यादिति विषयविशेषनिर्देशार्थं कृत्स्नं सूत्रमपेक्षितमिति भावः॥ नन्वधीगर्थेति कर्मणि शेषे वनगुल्मस्येतिषष्ठीसत्त्वात् कर्मणोऽभावेन नेदमुदाहरणमत आह—**कर्मोपलक्षणमिति**॥ अन्येत्वेतद्भाष्यबलात्सूत्रस्थकर्मपदं फलाश्रयपरं न तु कर्मसंज्ञकपरमित्याहुः॥ **एतदपि**। एनमित्येतद्घटितमुदाहरणमपि॥ **उपलक्षणम्**। तद्रहितोदाहरणस्येत्यर्थः। अकर्मकाण्येवोदाहरणानीति मत्वैव कर्मवद्भावात्सिद्धमिति भाष्यस्य प्रवृत्तेरिति भावः॥ यद्यपि गतिबुद्धीतिसूत्रे ज्ञानसामान्यार्थकानामेव ग्रहणमिति स्मरयतियोगे नाण्यन्तकर्तुः कर्मत्वप्राप्तिः। तथाप्येतद्भाष्यप्रामाण्यादाध्यानार्थकस्मरतेरपि तत्र ग्रहणं बोध्यमिति तात्पर्यम्॥

(प्रयोजननिराकरणभाष्यम्)

एतदपि नास्ति प्रयोजनम्। कर्मोपदिष्टा विधयः कर्मस्थभावकानां कर्मस्थक्रियाणां वा भवन्ति। कर्तृस्थभावकश्चायम्॥

(उद्द्योतः) एतदपीति। भाष्ये। आध्यानार्थानां कर्तृस्थक्रियत्वेन कर्मवद्भावाविषयत्वादिति भावः॥

(सूत्रसाधकभाष्यम्)

एवं तर्हि सिद्धे सति यदनाध्यान इति प्रतिषेधं शास्ति तज्ज्ञापयत्याचार्यः—भवत्येवंजातीयकानामात्मनेपदमिति॥ किमेतस्य ज्ञापने प्रयोजनम्?। पश्यन्ति भृत्या राजानम्। दर्शयते भृत्यान् राजा" अत्रात्मनेपदं सिद्धं भवति॥

(प्रदीपः) **भवत्येवंजातीयकानामिति**। येषामण्यन्तानां यत्कर्म तेषां ण्यन्तानां यदा स कर्ता तदा कर्तृस्थभावक्रियत्वेप्यात्मनेपदं भवतीत्यर्थः। एवं च ब्रुवता भाष्यकारेण सूत्रमेतद्विध्यर्थमित्यर्थादुक्तं भवति। तेनारोहयते हस्तीत्यादावनेनैवात्मनेपदं सिद्धं भवति। तथा हि—'दहिर्गतिविशेषवचनः' इति यद्धितुपरं छन्दसीत्यत्र भाष्यकारो वक्ष्यति॥ एवं चास्यते एवं च कर्तृस्थक्रियत्वाभावात्त्वत्र कर्मवद्भावः। एवं चारोह्यते हस्ती स्वयमेवेति ये कर्मवद्भावं प्रदर्शयन्ति ते न्यायं भाष्यं च बाधमाना अवधीरणीयाः। तथाहि—

विशेषदर्शनं यत्र क्रिया तत्र व्यवस्थिता ।
क्रियाव्यवस्था त्वन्येषां शब्दैरेव प्रकल्पिता ॥'

इति । विशेषदर्शनेन शब्दार्थानुसारेण वा तात्स्थ्यं कथ्यते क्रियायाः । एतच्च कारणद्वयमारोहणस्य कर्तृस्थतां प्रतिपादयति न कर्मस्थताम् । तथा हि—हस्तिनमारोहति वृक्षमारोहति पर्वतमारोहतीत्यादौ कर्मभेदेपि नारोहणस्य रूपभेदः प्रतीयते । न चैतेषु प्रयोगेषु क्रियाकृतः कर्मणि कश्चिद्विशेषो दृश्यते ॥ धातुना च कर्तृगतैव क्रिया प्रतिपाद्यते, न कर्मगता । केवलं कर्मणः कारकत्वादवश्यं क्रियया भाव्यमिति क्रियानुमीयते । सर्वाणि हि कारकाणि स्वं स्वं व्यापारमनुतिष्ठन्ति प्रधानक्रियां संपादयन्ति । बहुवक्तव्यश्चायमर्थः किंचित्तु प्रकृतोपयोगादुक्तमिति प्रकृतमनुसरामः ॥ **दर्शयते भृत्यान् राजेति** ॥ ननु कर्मान्तरसद्भावादत्रात्मनेपदेन न भाव्यम् । उच्यते—अस्मादेवोदाहरणाद्भाष्यकारस्यायमभिप्राय उन्नीयते—अण्यन्तावस्थायां ये कर्तृकर्मणी तद्व्यतिरिक्तकर्मान्तरसद्भावे आत्मनेपदं न भवति यथा स्थलमारोहयति मनुष्यानिति । इह त्वण्यन्तावस्थायां कर्तृणां भृत्यानां णौ कर्मत्वमिति भवत्येवात्मनेपदम् । एवं च स्मरयत्येनं वनगुल्मः स्वयमेवेति कोकिलस्य कर्मत्वेपि प्रत्युदाहरणं युज्यते ॥

(**उद्द्योतः**) **तज्ज्ञापयतीति** । प्रतिषेधप्रतियोगिसमर्पकं सूत्रं
बोधयतीत्यर्थः ॥ **एवंजातीयकानामित्यस्य** कर्तृस्थभावकानामित्यर्थे
पश्यति राजा स्वयमेवेत्यत्रापि स्यादत आह—**येषामण्यन्ताना-**
मिति ॥ **कर्तृस्थभावक्रियत्वेपीति** । अपिना सकर्मकत्वेपीत्यर्थः ॥
अत एव भाष्ये **एवंजातीयकाना**मिति चरितार्थमन्यथा **भवत्ये-**
षामित्येव वदेत् । सा(जात्यं च कर्मवद्भावाप्राप्तियोग्यत्वेनेति बो-
ध्यम् ॥ तदाह—**एवं चेति** । स्वातन्त्र्ये संभवति विध्यन्तरशेषत्व-
कल्पनाऽयुक्तेति भावः ॥ **प्रदर्शयन्त** इति भागवृत्तिकाराः ॥ **न्या-**
यम् । **विशेषदर्शनं यत्रेति** वक्ष्यमाणम् ॥ **भाष्यम्** । **यद्वितु-**
परमितिमन्त्रस्थम् ॥ तमेव न्यायमाह—**विशेषेति** । **यत्र** कर्मभे-
देन क्रियाजन्यफले **विशेषदर्शनं**, रूपभेददर्शनं **तत्र कर्मस्था,**
यथा पचेरोदनरोटिकादौ, अन्यत्र कर्तृस्थेत्यर्थः ॥ यद्वा क्रियाकृतवि-
शेषस्य यत्र कर्तरि प्रत्यक्षेणावधारणं तत्र **कर्तृस्था,** यत्र कर्मणि तत्र
कर्मस्थेत्यर्थः । इदं केषांचिन्मते ॥ अन्ये त्वेवं सति क्रियाजन्यश्रमा-
दिकृतवैलक्षण्यं प्रायेण सर्वत्र कर्तर्यस्तीति पचादेरपि कर्तृस्थभावक-
तापत्तिः । तस्माद्यद्धातुवाच्या फलांशरूपा क्रिया कर्तृगतापि संब-
न्धविशेषेण शब्देन बुध्यते स **कर्तृस्थक्रियः** । यद्धातुवाच्यः सोंशः
कर्मस्थ एव न कथमपि कर्तृस्थः स **कर्मस्थक्रियो** यथा पच्यदादा-
विति वदन्ति ॥ तदाह—**अन्येषामिति** ॥ नन्वत्र पक्षे दृशेः कर्मस्थक्रियत्वापत्तिः, विषयत्वापत्तिरूपस्यावरणभङ्गरूपस्य वा फलस्य कर्मण्येव सत्त्वादिति चेत् ॥ सत्यम्—ज्ञानानुकूलव्यापार एव तदर्थ इत्याशयात् ॥ **विशेषदर्शन**मित्यस्य दर्शितार्थव्याख्यारीत्याह—**कर्मभेदेपीति । नारोहणस्य** । न तज्जन्यफलस्य ॥ द्वितीयव्याख्यायामाह—**न चैतेष्विति** । एवं च निर्वर्त्यविकार्यकर्मणि निर्वृत्तिविकारलक्षणः कर्मणि विशेषः । प्राप्ये तु न,

क्रियाकृतविशेषाणां सिद्धिर्यत्र न लक्ष्यते ।
दर्शनादनुमानाद्वा तत्प्राप्यमिति कथ्यते ॥

इति तल्लक्षणादिति भावः ॥ अन्येषां मतेपि कर्मस्थक्रियात्वं निराकरोति—**धातुना चेति** ॥ **कर्तृगतैवे**त्यस्य कर्तृगापीत्यर्थः ॥ **न कर्मगते**त्यस्य न कर्मगतैवेत्यर्थः ॥ ननु न्यग्भवनं विनोपरिगमनमसंभवीत्यत उक्तम्—**केवलमित्यादि** । अत एव हरिणापि—

'न्यग्भावनं न्यग्भवनं रुहौ शुद्धे प्रतीयते'

इत्येवोक्तं, न तु रुहिणा प्रतिपाद्यत इति ॥ [नन्वेवं सति धात्वर्थतावच्छेदकफलाश्रयत्वाभावाद्धस्तिनः कर्मत्वानापत्तिरत आह—**बहु वक्तव्य इति** । अयं भावः—न्यग्भवनानुकूलव्यापारस्य रुहर्थत्वे तदनुकूलतयाऽङ्कुशेन गजं ताडयत्यप्यारोहतीतिप्रयोगापत्तिः । उपरिगमनमपि धात्वर्थश्चेत् तदेवास्तु तावतैव हस्तिनः कर्मत्वोपपत्तिः, किं न्यग्भवनेनेति । उपरिगमनस्य संबन्धविशेषेण कर्तर्यपि सत्त्वान्न कर्मस्थक्रियत्वमिति भावः ॥] **नन्विति** । उपक्रमस्थकर्मान्तरनिवृत्तिपरवाक्येनाकर्मकाणामेवैतदुदाहरणत्वावगतेरिति भावः ॥ **अस्मादेवोदाहरणादिति । एवंजातीयकाना**मित्युक्तिपराच्च **यस्माण्णेः प्राक्कर्म कर्त्ता चे**ति भाष्याच्चेत्यपि बोध्यम् । **प्राक्कर्मकर्ता चे**त्यनेन प्राक्स्थितकर्मकर्त्रोरेतदात्मनेपदोपयोगित्वं बोध्यते । तच्च कर्तृकर्मातिरिक्तकर्माभावबोधने एवेत्याहुः ॥ **कर्तृकर्मणी** इति ॥ **कर्तरि कर्मे**त्यतः कर्तृग्रहणमनुवर्त्य प्रथमया विपरिणमय्य यच्च यश्च यदित्येकशेषेणायमर्थो लब्धः ॥ **प्रत्युदाहरणं युज्यते इति** । सिद्धान्ते इति शेषः । स्थलमारोहयतीत्यत्रापि स्थलस्य कर्तृकर्मातिरिक्तकर्मणः सत्त्वात् ॥

(९५७ आक्षेपवार्तिकम् ॥ ८ ॥)

॥ * ॥ आत्मनः कर्मत्वे प्रतिषेधः ॥ * ॥

(भाष्यम्) **आत्मनः कर्मत्वे प्रतिषेधो वक्तव्यः । 'हन्त्यात्मानम् घातयत्यात्मा' इति ।**

(प्रदीपः) **आत्मनः कर्मत्वे इति** । यदैकमेव वस्तु बुद्ध्या विभज्य कर्मत्वेन कर्तृत्वेन च विवक्ष्यते तदा प्रतिषेध इत्यर्थः ।

(उद्द्योतः) भाष्ये—आत्मनः कर्मत्वे प्रतिषेध इति । अण्यन्ते कर्मण आत्मनो ण्यन्ते कर्तृत्वेनाण्यन्तावस्थास्थकर्तृकर्मातिरिक्तकर्माभावेन नात्मनेपदस्यैतत्प्राप्तस्य प्रतिषेधो वक्तव्य इत्यर्थः । भाष्योदाहरणे आत्मानमित्युभयत्रापि ।

(तदस्याक्षेपभाष्यम्)

स तर्हि वक्तव्यः ।

(९५८ समाधानवार्तिकम् ॥ ९ ॥)

॥ * ॥ न वा ण्यन्तेऽन्यस्य कर्तृत्वात् ॥ * ॥

(भाष्यम्) न वा वक्तव्यः । किं कारणम् ? ण्यन्तेऽन्यस्य कर्तृत्वात् । अन्यदत्राण्यन्ते कर्म अन्यो ण्यन्तस्य कर्ता ॥ कथम् ? । द्वावात्मानौ । अन्तरात्मा शरीरात्मा च । अन्तरात्मा तत्कर्म करोति येन शरीरात्मा सुखदुःखे अनुभवति । शरीरात्मा तत्कर्म करोति येनान्तरात्मा सुखदुःखे अनुभवतीति ॥ णेरणौ ॥ ६७ ॥

(प्रदीपः) **नवेति** । वस्तुत एवात्र आत्मभेदो न त्वेकस्यैव कर्मत्वं कर्तृत्वं चेत्यर्थः ॥ **अन्तरात्मेति** । सांख्यपक्षेऽन्तःकरणमन्तरात्मा तस्यैव कर्तृत्वसंभवात्पुरुषस्याकर्तृत्वात् । नैयायिकादीनां तु मते पुरुषस्य कर्तृत्वात्स एवान्तरात्मा विवक्षितः ॥ **शरीरात्मा सुखदुःखे इति** । शरीरस्याचेतनत्वात्सुखदुःखहेतुभ्यां शरीरं संबध्यत इति व्याख्येयम् ॥ ६७ ॥

(उद्द्योतः) **वस्तुत एवेति** । अयं भावः—शरीरात्मा कर्म । अहं काण इत्यादिव्यवहारेण शरीरेऽपि लोकानामात्मत्वप्रत्ययाच्छरीरात्मेति न विरुद्धम् । अन्तरात्मा कर्ता शरीरात्मनि कर्तृत्वस्य लौकिकैरप्यनभ्युपगमादिति [भावः] ॥ नन्वन्तरात्मा पुरुषः सोऽप्यकर्तैव सांख्यादिमतेऽत आह—**सांख्येति** । **तस्यैवेति** । तन्मते पुरुषस्य पुष्करपलाशवन्निर्लेपत्वेन कर्तृत्वाधनाश्रयत्वादिति भावः ॥ **पुरुषस्य** । जीवस्य ॥ भाष्ये आत्मद्वयसत्त्वे मानमाह—**अन्तरात्मेत्यादिना** । **तत्कर्मेति** । धर्माधर्मरूपं यत्पूर्वसञ्चितं कर्म तत्फलं पादादिसौख्याद्यनुभवतीतिलौकिकव्यवहारात् । पूर्वकृतं कर्म मामाधिरूपेण बाधते इति व्यवहाराच्चेति भावः ॥ शरीरात्मनः कर्म चेष्टादिरूपं सुखदुःखजनकम् । एकस्यैवात्मनः कक्ष्यान्तरे कर्तृत्वं त्वनभिधानान्नेति सिद्धान्ताशयः ॥ ६७ ॥

(१५७ आत्मनेपदनियमसूत्रम् । १ । ३ । २ आ. २८ सू.)

२१९ स्वरितञितः कर्त्रभिप्राये क्रियाफले ॥ १।३।७२ ॥

(प्रदीपः) **स्वरितञितः** ॥७२॥ इदमात्मनेपदं संविधानवृत्तिभ्यो धातुभ्यो भवतीति केचिद्व्याचक्षते । पचते पाचयतीत्यर्थः । यजते याजयतीत्यर्थः । अनेकार्थत्वाद्धातूनां प्रकृतिरेव यदा संविधाने वर्तते तदा तस्य द्योतकमात्मनेपदं भवति । यदा तु प्रकृत्यानभिहितं संविधानं तदा तदभिधानाय णिजुत्पद्यते पाचयतीति । यदा णिचश्चेति ण्यन्तादात्मनेपदं भवति तदा द्वितीये संविधाने ण्यन्तस्य वृत्तिः परिकल्पनीया, यथा राजा पाचयते इति । **कर्त्रभिप्राये क्रियाफलइत्यनेन** संविधानलक्षण एव क्रियाविशेष उपलक्ष्यते । क्रीणीष्व वैपते धत्ते चिनुतइति च शिष्टप्रयोगेषु ण्यर्थोऽवगम्यते । स्वरितञित एव संविधाने शब्दशक्तिस्वाभाव्याद्वर्तन्ते नान्ये धातव इति स्वरितञिद्ग्रहणं भाष्ये प्रत्याख्यातम् ॥ अन्ये त्वाहुः—स्वार्थं यः क्रियामारभते तत्रात्मनेपदं परार्थारम्भे तु परस्मैपदम् । सा च स्वार्थपरार्थता विवक्षानिमित्ता लौकिके प्रयोगे स्वरितञिद्विषयैव, न यात्यादिविषयेत्यत्रापि पक्षे स्वरितञिद्ग्रहणस्य प्रत्याख्यानम् ॥ एवं पञ्चभिर्हलैः कृषतीति **विभाषोपपदेन प्रतीयमानइति** पक्षे आत्मनेपदाभावः । स्वामिदासौ पचत इति क्रियामात्रविवक्षायां परस्मैपदम् । यदा तु स्वामिगतो धर्मो दास आरोप्यते तदा स्वामिदासौ पचेते इति आत्मनेपदं भवत्येव ॥

(उद्द्योतः) **स्वरितञितः** ॥ ७२ ॥ ननु राजा प्रयाति सेना प्रयातीत्यादौ क्रियाफलस्य जयस्य कर्तृगामित्वतदभावयोर्दर्शनेन यात्यादिव्यावृत्तये स्वरितञित इत्यस्यावश्यकत्वेन भाष्यमनुपपन्नमत आह—**इदमिति** । अत्र केचित्—**क्रिया** कृत्स्नधात्वर्थस्तत्फलके **कर्तुः** प्रयोजककर्तुर**भिप्राये**ऽभिप्रायमूलके प्रयोजककर्तृव्यापारे आत्मनेपदमित्यर्थादिति भावः ॥ **संविधानं** कृत्स्नधात्वर्थप्रवृत्त्यनुकूलः प्रवर्तनाख्यो व्यापारः । यजेतेत्यादौ च ऋत्विक्प्रवृत्त्यनुकूलो यजमानव्यापार एव धात्वर्थः । सर्वावयवकक्रियाप्रवृत्त्यनुकूलव्यापार एव संविधानशब्दवाच्यः । तेन यजेत पशुकाम इत्यादौ यजनान्तर्गतस्तोत्रशंसनरूपहोतृव्यापारप्रयोजकव्यापारकर्तुरध्वर्योरपि पशुना संबन्धः स्यादित्यपास्तम् । तद्व्यापारस्य यजमानव्यापारवद्यावयज्यर्थप्रवृत्त्यनुकूलत्वाभावेन संविधानत्वाभावादित्याहुः ॥ परे तु **संविधानं** सामग्रीसंघटनरूपमित्याहुः ॥ ननु विक्लित्याद्यनुकूलव्यापार एव पचत्याद्यर्थो न तु तन्निमित्तं संविधानमपीत्यत आह—**अनेकार्थत्वादिति** ॥ **तस्य द्योतकमिति** । अनेन तस्य विशेषणत्वं सूचयति । संविधानविषय एककर्तृकः पाक इत्यर्थः ॥ परे त्वनेकार्थस्य धातोरत्रायमेवार्थ इति बोधनमेव द्योतकत्वं, तेन विशेष्यत्वेपि न क्षतिरित्याहुः ॥ तदाह—**यथा त्विति** ॥ **हेतुमतीति** प्रत्ययार्थनिर्देश इत्येव सिद्धान्तः ॥ अत एव तदाश्रयस्यैव तत्र कर्तृत्वम् । तदाह—**तदभिधानायेति** । किं च यात्यादीनां संविधाने वृत्त्यभाववादिनां तत्र णिजनापत्त्या णिज्विधायके वाचकतापक्ष एवावश्यक इत्याशयः ॥ नन्वेवं ण्यन्तादात्मनेपदं न स्याद् णिचा संविधानस्य बोधितत्वादत आह—**यदेति** । **तस्य**, ण्यन्तस्य ॥ नन्वयमर्थः सूत्रानारूढोऽत आह । **कर्त्रभिप्राये इत्यादि** । तदुक्तम्—

कर्त्रभिप्रायता सूत्रे क्रियाभेदोपलक्षणम् ।
तथाभूता क्रिया सा हि तत्कर्त्ता फलभाग्यतः ॥"

इति ॥ क्रियाभेदः संविधानलक्षणः ॥ तत्कर्ता संविधानकर्ता ॥

"केषां चित्कर्त्रभिप्राये णिचा सह विकल्पते ।
आत्मनेपदमन्येषां तदर्थां प्रकृतिर्यथा ॥"

इति च ॥ केषांचिद्धातूनां स्वरितञितां केषांचिद्वादिना- मिति वा ॥ एवमन्येषामित्यपि बोध्यम् ॥ विकल्पाङ्गीकारे शिष्टप्रयोगान् प्रमाणत्वेन दर्शयति—क्रीणीष्वेति ॥ वपत इति पाठः ॥ अत्र पक्षे प्रत्याख्यानभाष्यं योजयति—स्वरितञित एवेति ॥ नन्वयं पक्षो न भाष्यसंमतः प्रत्याख्यानभाष्ये सर्वेषां च कर्त्रभिप्रायं क्रियाफलमस्ति [तस्मादुभयवद्भ्य आत्मनेपदम्] न चैतेषामुभयमस्तीत्युक्तेः । तत्र सर्वेषां कर्त्रभिप्रायं क्रियाफलमस्तीत्युपक्रमादुभयाभावोऽकर्त्रभिप्रायत्वाभावप्रयुक्तो लभ्यते । असंविधाने एषां वृत्तिर्नास्तीति तु वक्तुमशक्यं देवदत्तो गच्छतीत्याद्यनापत्तेः । तस्मादुत्तरव्याख्यैव युक्ता । तत्र हि यात्यादौ तत्फलस्य सर्वदा कर्तृगामित्वमेव विवक्षितम्, न तु परगामित्वमित्यस्य सुवचत्वात् ॥ प्रतीयते च तथैव यात्यादौ । एवं च न चैषां कर्त्रभिप्रायं चेत्यादिप्रतीकस्थकैयटोपि चिन्त्य एव । चिनुते इत्यादिप्रयोगाश्चान्तर्भावितण्यर्थतयोपपाद्याः । प्रकरणादिकं च तात्पर्यग्राहकम् । कदाचित्परस्मैपदेपि तत्प्रतीत्या तस्यावश्यकत्वाच्च । न च सेना प्रयातीत्यादौ यात्यादीनामपि पराभिप्रेतफलत्वमस्त्येवेति वाच्यम् । भाष्ये चश्रवणेन कर्त्रभिप्रायमेवाकर्त्रभिप्रायमेव च क्रियाफलमस्तीत्यर्थात् । अत्र जयादिफलमुभयाभिप्रेतमिति न तथेति भावादित्यरुचेराह—अन्ये त्वाहुरिति । स्वार्थं च इति । यः स्वार्थं क्रियामारभते तत्र तद्विषये प्रयोगे इत्यर्थः । सूत्रे कर्तृगामित्वं कर्तुरुपकारकत्वम्, न तु संयोगः समवायो वा । चित्रया यजेत पशुकाम इत्यादौ तद्भावात् । एवं च फलद्वारा क्रियैव कर्त्रर्थेति फलितम् । अत्र पक्षे क्रियाफलं श्रुत्वा लोकतो वा यदुद्देशेन क्रियाप्रवृत्तिरवगता तथ्या पच्यादौ भोजनादि लोकतोऽवगतम्, यज्यादौ च स्वर्गादि श्रुत्वाऽवगतम्, न दक्षिणादिरूपमिति बोध्यम् ॥ परार्थेति । यात्यादिषु तु परार्थत्वविवक्षैव नास्तीत्यतो न दोषः । स्वार्थत्वपरार्थत्वोभयविवक्षावतां धातूनां स्वार्थत्वविवक्षायां तङानाविति सूत्रार्थः । उभयं च स्वरितञित्स्वेवेति न दोषः । विवक्षानिमित्ता स्वार्थपरार्थतेत्यन्वयः । विवक्षेत्यनेन 'कमलवनोद्घाटनं कुर्वते ये' इति सिद्धम् । अत एव स्वामिदासौ पचत इत्यत्र क्रियामात्रविवक्षायां परस्मैपदमिति वक्ष्यते कैयटेन । तेन चैतस्य शाब्दबोधे भानमिति लभ्यते । कर्तृगामित्वविवक्षाभावमात्रं परस्मैपदनिमित्तमिति च । आत्मनेपदादिसमभिव्याहृतधातोः स्वरितञितः कर्तृगतफलजनकक्रियादौ लक्षणेति बोध्यम् ॥

केचित्तु नेदं शाब्दबोधविषयः अपि तु पश्चात्तनमानसबोधविषयस्तथैवानुभवात् । किमर्था क्रियेति विचारे कचित् परार्थफलकत्वम् कचित् स्वार्थफलकत्वं मनसा बुध्यते । एवं चैतु परार्थत्वमेव परस्मैपदनिमित्तं कोटिद्वयातिरेकेण तृतीयकोटेरभावात् । अत एव भाष्येऽकर्त्रभिप्रायमित्युक्तम्, न तु कर्त्रनभिप्रायमिति । स्वामेदासौ पचत इति तु दासधर्मस्य स्वामिन्यारोपात्साध्यम् । स्वामिगतस्य धर्मस्य दासे आरोपेणात्मनेपदवत् । कर्त्रभिप्रेतत्वादिकं चारोपितानारोपितसाधारणं मानसबोधविषयस्तङादिहेतुः ॥ अत एव परार्थारम्भे तु परस्मैपदमित्युपक्रमे कैयटेनोक्तम् । वस्तुतः कर्त्रभिप्राये क्रियाफले इत्यनेन संविधानमुपलक्ष्यते । तद्वाचकाद्धातोरात्मनेपदं विक्लित्यनुकूलसाधनविनियोगार्थत्वे तु परस्मैपदम् ॥ एतच्च हरिग्रन्थे स्पष्टमिति मञ्जूषायां निरूपितम् ॥ भाष्यस्याप्यत्रैव तात्पर्यमित्याहुः ॥

नन्वेवं विवक्षाऽतिप्रसक्तेत्यत आह—स्वरितञिद्विषयैवेति ॥ नन्वेवं पञ्चभिर्हलैः कृषतीत्यत्र संविधानप्रतीतेरात्मनेपदं स्यादत आह—पञ्चभिरिति । पञ्चभिर्हलैरित्युपपदगम्यत्वात्तस्येति भावः ॥ ननु स्वामिदासयोर्युगपत्कर्तृत्वविवक्षायां स्वार्थवृत्तिताप्रयुक्तात्मनेपदस्य दासेनान्वयाभावात् परार्थत्वप्रयुक्तपरस्मैपदस्य स्वामिनाऽनन्वयादप्राप्त्यैदृशे विषये पचेस्तिङन्तस्य प्रयोग एव न स्यादत आह—स्वामिदासाविति । क्रियामात्रेति । वस्तुत उपपत्त्यन्तरमत्रोक्तम् ॥

(स्वरितञिद्ग्रहणप्रत्याख्यानाधिकरणम्)

(आक्षेपभाष्यम्)

स्वरितञित इति किमर्थम् ? ।

(समाधानभाष्यम्)

याति वाति द्राति प्साति ॥

(प्रत्याख्यानभाष्यम्)

स्वरितञित इति शक्यमकर्तुम् ॥

(आक्षेपभाष्यम्)

इह कस्मान्न भवति याति वाति द्राति प्सातीति ।

(समाधानभाष्यम्)

'कर्त्रभिप्राये क्रियाफले' इत्युच्यते । सर्वेषां च कर्त्रभिप्रायं क्रियाफलमस्ति । त एवं विज्ञास्यामः येषां कर्त्रभिप्रायमकर्त्रभिप्रायं च क्रियाफलमस्ति तेभ्य आत्मनेपदं भवतीति । न चैषां कर्त्रभिप्रायं चाकर्त्रभिप्रायं च क्रियाफलमस्ति । तथाजातीयकाः खल्वाचार्येण स्वरितञितः पठिताः ये उभयवन्तः—येषां कर्त्रभिप्रायं चाकर्त्रभिप्रायं च क्रियाफलमस्ति ॥

(प्रदीपः) सर्वेषां चेति । सर्वत्र संविधानस्य संभवात्सर्वत्र च स्वार्थानुष्ठानसंभवादिति भावः ॥ येषामिति । संभवे व्यभिचारे च सति प्रकारान्तरव्यवच्छेदेन विशिष्टे कार्य-

विधानाय विषयनिर्देशः क्रियते इति भावः ॥ **न चैषा-मिति** । यात्यादयः संविधाने वर्तितुं न शक्नुवन्तीत्यर्थः । अथ वा स्वाभिधेयमात्रवृत्तयो यात्यादयः तैषां स्वार्थताविशिष्टक्रियावाचित्वसंभवः ॥ **तथाजातीयका इति** । प्रकारमात्रे थालं विधाय प्रकारवति जातीयर् विहितः ॥

(उद्द्योतः) **सर्वत्रेति** । सर्वधातुष्वित्यर्थः ॥ भाष्ये **सर्वेषा-मि**त्यस्यापि सर्वधातूनामित्यर्थः ॥ **संभवे इत्यादि** । एवं च यत्र धातौ कर्त्रभिप्राय इत्यस्य व्यावर्त्यसंभवस्तत्रैवास्य प्रवृत्तिरिति भावः ॥ **अकर्त्रभिप्राय**मित्यस्य कर्तृभिन्नाभिप्रायमित्यर्थः । एवं च यात्यादीनां सर्वथा कर्त्रभिप्रेतमेवेति व्यावर्त्याभावात्तेषां नोदाहरणत्वमिति भावः ॥ **तेलेषां स्वार्थताविशिष्टेति** । क्रियामात्रवृत्तित्वादिति भावः । एतदुक्तरीत्या भाष्यस्वरसविरुद्धम् । अकर्त्रभिप्रेतक्रियाफलाभावस्यैव भाष्यतो लाभादिति कश्चित् ॥ प्रत्यययोः पौनरुक्त्यं परिहरति—**प्रकारमात्रे इति** । केचित्तु तथाजातिरिति बहुव्रीहेर्जात्यन्ताच्छ बन्धुनीति छमाहुः ॥

(अभिप्रग्रहणप्रयोजनाधिकरणम्)

(आक्षेपभाष्यम्)

अथाभिप्रग्रहणं किमर्थम् ? ॥

(प्रदीपः) **अथेति** । कर्तारमेति प्राप्नोतीति कर्त्रायमिति सिद्धत्वेव विवक्षितोर्थ इति प्रश्नः ॥

(उद्द्योतः) नन्वभिप्रपूर्वकैतेरिच्छायां रूढत्वेन कथं तदाक्षेपोऽत आह—**कर्त्रायमिति** । स तु न तव विवक्षित इति भावः ॥

(समाधानभाष्यम्)

स्वरितञितः कर्त्राये क्रियाफल इतीयत्युच्यमाने यमेव संप्रत्येति क्रियाफलं तत्रैव स्यात्—लूञ् लुनीते, पूञ् पूनीते । इह न स्यात्—यज् यजते, वप् वपते । अभिप्रग्रहणे पुनः क्रियमाणे न दोषो भवति । अभिराभिमुख्ये वर्तते । प्र आदिकर्मणि । तेन यं चाभिप्रैति यं चाभिप्रैष्यति यं चाभिप्रागात्तत्र सर्वत्राभिमुख्यमात्रे सिद्धं भवति ॥

(प्रदीपः) **यमेवेति** । केचिदाहुः—वर्तमानकालविवक्षा स्यादिति । तदयुक्तम् । कालसामान्येऽभिधानात् ॥ तस्मादयमर्थः—द्विविधं यागादिफलं दृष्टमदृष्टं च । दृष्टं अन्नपुत्रवृष्टिशत्रुवधादिकम् । अदृष्टं स्वर्गादि ॥ तत्र—पूर्वं प्रत्यासन्नमवश्यंभावीति प्रधानम् । इतरत्तु विधुरप्रत्ययोपनिपातसम्भवे व्यभिचारसंभवाद्विप्रकृष्टत्वाच्चाप्रधानमिति तस्येह ग्रहणं न स्यात् । अभिप्रग्रहणात्तु तस्यापि ग्रहणम् । आभिमुख्यं फलस्य यदा कर्ता बुद्ध्याध्यवस्यति क्रियारम्भे तदा आत्मनेपदमित्ययमर्थोऽभिप्रग्रहणे सति लभ्यते ॥ **वपत इति** । केशश्मश्रु वपत इत्यत्रैवासन्ने फले स्यात् । धान्यं वपत इत्यत्र तु विप्रकृष्टे फले न स्यादित्यर्थः ॥ **यं चाभिप्रागादिति** । अयष्टेत्यादौ । एतत्तु कालनिर्देशप्रसङ्गेनोक्तं न त्वप्राप्तेर्निमित्तमस्ति ॥

(उद्द्योतः) **केचिदिति** । संप्रत्येतीति भाष्यस्वरसादिति तेषां भावः । यद्यप्यण्विधौ कालसंबन्धो नास्ति तथापि कालोदासीनाः प्रत्यया आक्षिप्यमाणकालत्रयसाधारणा इत्यभिप्रायेण **कालसामान्ये इत्युक्तम्** ॥ **तस्मादिति** । संप्रतीति क्रियाफलविशेषणं संप्रतीत्यस्य क्रियाऽव्यवहितोत्तरकालिकमित्यर्थः । तच्च दृष्टमेवेति भावः ॥ तद्ध्वनयन्वक्ष्यति—इह न स्याद् यजत इत्यादि ॥ **विधुरो**, विरोधी ॥ **प्रत्ययः** कारणम् ॥ **तदुपनिपात**,स्तत्प्राप्तिः । कीर्तनेन, कर्मनाशाजलस्पर्शकरतोयापारगमनविस्मयादिरूपविरोधिकारणसांनिध्ये विनाशसंभवादिति भावः ॥ **विप्रकृष्टत्वं**, कालान्तरभावित्वम् ॥ **अभिप्रग्रहणात्त्विति** । तदभावेऽवश्यभावित्वं संनिहितत्वमेव च प्राधान्यं गृह्येत । सति तु तस्मिन् क्रियोद्देश्यत्वलक्षणप्राधान्यविशेषलाभ इति भावः ॥ क्रियाप्रारम्भे यदा कर्ता फलस्याभिमुख्यमुद्देश्यत्वं बुद्ध्या जानाति तदात्मनेपदमित्यन्वयः । एवं च तादृशोद्देश्यमेव फलशब्देन लभ्यत इति तात्पर्यम् । इदमेवाभिप्रेत्य वक्ष्यति—**अभिराभिमुख्ये प्र आदिकर्मणीति** । आद्यत्वं चाभिमुख्यगतम् । आद्यमाभिमुख्यं च कर्मप्रारम्भकालिकमेवेति दिक् ॥ ननु वपनस्य केशकर्तनरूपं फलमव्यवहितमेवेति कथमिहाप्राप्तिरत आह—**केशेति** । **धान्यं वपते इति** । बीजविकरणार्थोऽत्र वपतिरिति भावः ॥ भाष्ये **तेन यं चेत्यादि** । अत्राभिप्रैतिः संबन्धमात्रे । एवं च येन फलेन संप्रति कर्ता संबद्धो, येन च संबद्धो भविष्यति येन च संबद्धोभूत्सर्वत्रात्मनेपदं सिद्धं कर्मारम्भे तस्यैव स्वसंबन्धित्वेनोद्देशात् । तत्र भूते उपयोगोऽलाविष्ट देवदत्त इत्यादौ ॥

(कर्त्रभिप्रायेक्रियाफलद्वयस्यप्रयोजनाधिकरणम्)

(आक्षेपभाष्यम्)

कर्त्रभिप्राये क्रियाफले इति किमर्थम् ? ॥

(समाधानभाष्यम्)

पचन्ति भक्तकराः । कुर्वन्ति कर्मकराः । यजन्ति याजकाः ॥

(समाधानबाधकभाष्यम्)

कर्त्रभिप्राये क्रियाफल इत्युच्यमानेपि प्राप्नोति । अत्रापि हि क्रियाफलं कर्तारमभिप्रैति । याजका यजन्ति गा लप्स्यामह इति । कर्मकराः कुर्वन्ति पादिकमहर्लप्स्यामह इति ।

(प्रदीपः) **पादिकमहरिति** । पादो भृतिरस्येत्यत्रार्थेऽसमासे निष्कादिभ्य इति ठक् ॥

(उद्द्योतः) भाष्ये—**अत्रापि हीति** । न च तानि फलानि न क्रियारम्भोद्देश्यानीति वाच्यम् । ऋत्विग्व्यापारवचनयजेरारम्भो होता भविष्यामीत्यादिप्रतिवचनं, तदुद्देश्याश्च गाव एवेति भावः ॥ **पादो भृतिरस्येति** । पादभृतिसंबन्धि दिनमित्यर्थः । दिवसस्य तां भृतिं लप्स्यामह इति तात्पर्यम् ॥

(समाधानसाधकभाष्यम्)

एवं तर्हि 'कर्त्रभिप्राये क्रियाफले' इत्युच्यते ।

सर्वत्र च कर्तारं क्रियाफलमभिप्रैति । तत्र प्रकर्षगतिर्विज्ञास्यते—साधीयो यत्र कर्तारं क्रियाफलमभिप्रैति । न चान्तरेण यजिं यजिफलं वपिं वा वपिफलं लभन्ते । याजकाः पुनरन्तरेणापि यजिं गा लभन्ते भृतकाश्च पादिकमिति ॥ स्वरित ॥७२॥

(प्रदीपः) **न चान्तरेणेति**। नहि स्वर्गादिफलं यागमन्तरेण भवति तदुद्देशेनैव यागप्रवर्तनात् ॥ **याजका इति**। प्रतिग्रहेणापीति भावः ॥ तथा च हरिणोक्तम्—

यस्यार्थस्य प्रसिद्ध्यर्थमारभ्यन्ते पचादयः ।
तत्प्रधानं फलं तेषां न लाभादि प्रयोजनमिति ॥७२

(उद्द्योतः) भाष्ये—**सर्वत्र चेति**। नहि प्रयोजनमनुद्दिश्येति न्यायादिति भावः ॥ **प्रकर्षेति** । अनन्यलभ्यत्वं प्रकर्षः ॥ **साधीय** इत्यस्य क्रियाफलेनान्वयः । अनन्यलभ्यं क्रियाफलं यत्र संविधानरूपे धात्वर्थे सति कर्तारमभिप्रैति तत्र तज्ज्ञानावित्यर्थ इति भावः ॥ किं तत्साधीयः क्रियाफलं तत्राह—**न चान्तरेणेति** । यद्यज्यादिफलमन्तरेण यजिक्रियां न च नैव लभन्ते तदित्यर्थः ॥ गवादिषु च तद्व्यतिरेकं दर्शयति—**याजकाः पुनरित्यादिना** । तद्व्याचष्टे—**नहीति** । यद्यपि दानादिनापि स्वर्गो भवति, तथापि स्वर्गविशेषस्य क्रियाविशेषनियतत्वादनन्यलभ्यत्वमिति भावः ॥ **तदुद्देशेन** । विशेषोद्देशेन । एवं च क्रियाफलशब्देन तदेव ग्राह्यमिति भावः । कारिकायां यत्सिद्ध्यर्थं पचादय एवारभ्यन्त इत्यन्वयः । एवकाराध्याहारश्च बोध्यः ॥ ७२ ॥

(इत्यात्मनेपदप्रकरणम्)

(अथ परस्मैपदनियमप्रकरणम्)

(१५८ परस्मैपदनियमसूत्रम् । १ । ३ । २ आ. २१ सू.)

२२५ शेषात्कर्तरि परस्मैपदम् ॥ १।३।७८ ॥

(कर्मकर्तरिप्रतिषेधाधिकरणम्)

(९५९ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ शेषवचनं पञ्चम्या चेदर्थे प्रतिषेधः ॥ * ॥

(भाष्यम्) **शेषवचनं पञ्चम्या चेदर्थे प्रतिषेधो वक्तव्यः । भिद्यते कुसूलः स्वयमेव, छिद्यते रज्जुः स्वयमेवेति ॥**

(प्रदीपः) **शेषात्कर्तरि ॥७८॥ भिद्यते कुसूल इति**। कुसूलस्य कर्मशास्त्रातिदेशेपि स्वाश्रयं कर्तृत्वमनिवृत्तमिति परत्वात्परस्मैपदं प्राप्नोति । सप्तम्यन्तेन तु शेषशब्देन कर्तरि विशेष्यमाणे कर्मकर्तुः कर्मवद्भावेन कर्मशास्त्रातिदेशादात्मनेपदविधानप्रयोगादशेषत्वात्परस्मैपदाभावः ॥

(उद्द्योतः) शेषात्कर्तरि ॥ ७८ ॥ भाष्ये—**अर्थे** कर्मकर्तृरूपे ॥ **प्रतिषेध इति** । परस्मैपदस्येति शेषः ॥ कार्यातिदेशे कर्मवच्छास्त्रस्य परत्वेनात्मनेपदं सिद्ध्यत्येवेत्यत आह—**शास्त्रेति** । वस्तुतः कार्यातिदेशेप्युपदेशदेश एव देशः । तस्य शास्त्रातिदेशानतिरेकश्चेति न दोष इति बोध्यम् ॥ नन्वेवमपि विशेषविहितेनातिदेशिकेनोपदेशस्य बाधः स्यादत आह—**स्वाश्रयमिति** । अचारितार्थ्यमेव हि बाधकत्वे बीजम् । अतिदेशश्च यगादिसंपादनेन चरितार्थ इति भावः ॥

(न्यासान्तरसमाधानभाष्यम्)

एवं तर्हि शेषे इति वक्ष्यामि ॥

(उद्द्योतः) भाष्ये शेष इति । एवं च **भावकर्मणोरिति** नियमे उपयुक्तत्वान्नायं शेष इति भावः ॥

(९६० न्यासान्तरदूषणवार्तिकम् ॥ २ ॥)

॥ * ॥ सप्तम्या चेत्प्रकृतेः प्रतिषेधः ॥ * ॥

(भाष्यम्) **सप्तम्या चेत्प्रकृतेः प्रतिषेधो वक्तव्यः । आस्ते शेते च्यवन्ते प्लवन्ते ॥**

(प्रदीपः) **सप्तम्या चेदिति** । प्रत्ययनियमे प्रकृतीनामनियमादनुदात्तङिद्भ्यः परस्मैपदमपि प्राप्नोति ॥

(उद्द्योतः) ननु प्रकृतिनियमेनुदात्तङिदादिभ्यो व्यावृत्तं परस्मैपदं शेषेभ्य एवेति किं तेनेत्यत आह—**प्रत्ययनियम इति**।

(९६१ समाधानतात्पर्यवार्तिकम् ॥ ३ ॥)

॥ * ॥ सिद्धं तूभयनिर्देशात् ॥ * ॥

(भाष्यम्) **सिद्धमेतत् ॥ कथम्? । उभयनिर्देशः कर्तव्यः । शेषाच्छेष इति वक्तव्यम् ॥**

(आक्षेपभाष्यम्)

कर्तृग्रहणमिदानीं किमर्थं स्यात् ? ।

(९६२ समाधानवार्तिकम् ॥ ४ ॥)

॥ * ॥ कर्तृग्रहणमनुपराद्यर्थम् ॥ * ॥

(भाष्यम्) **अनुपराद्यर्थमेतत्स्यात् । इह मा भूत्—अनुक्रियते स्वयमेव, पराक्रियते स्वयमेवेति ॥**

(प्रदीपः) **अनुक्रियतइति । अनुपराभ्यां कृञ** इत्येतदशेषार्थमारब्धम् । गन्धनादिषु कर्त्रभिप्राये क्रियाफले च परस्मैपदार्थम् । तत्रासतीह कर्तृग्रहणे कर्मकर्तर्यपि परस्मैपदप्रसङ्गः । सति तु कर्तृग्रहणे उत्तरत्र शेषग्रहणस्य कर्तृग्रहणस्य चानुवृत्तौ सत्यां शेषे कर्तरि परस्मैपदविधानात्कर्मकर्तरि न भवति ॥ ७८ ॥

(उद्द्योतः) अशेषं दर्शयति **गन्धनादिष्विति** । एवं च गन्धनादौ प्राप्तमात्मनेपदं यथा बाधते तथा सति कर्तृग्रहणे कर्म-

कर्त्रर्थेपि तद्बाधेतेति भावः ॥ सति स्विति । इहकरणं तु स्पष्टार्थमिति भावः ॥ ७८ ॥

(आक्षेपभाष्यम्)

सिद्ध्यति । सूत्रं तर्हि भिद्यते ॥

(सिद्धान्तिभाष्यम्)

यथान्यासमेवास्तु ॥

(आक्षेपकारणभाष्यम्)

ननु चोक्तम्—* शेषवचनं पञ्चम्या चेदर्थे प्रतिषेधः* इति ।

(समाधानभाष्यम्)

नैष दोषः । "कर्तरि कर्मव्यतिहारे" इत्यत्र कर्तृग्रहणं प्रत्याख्यायते तत्प्रकृतमिहानुवर्तिष्यते शेषात्कर्तरि कर्तरीति । कर्तैव यः कर्ता तत्र यथा स्यात्, कर्ता चान्यश्च यः कर्ता तत्र मा भूदिति ॥ शेषात्कर्तरि ॥ ७८ ॥

(१५९ परस्मैपदनियमसूत्रम् । १ । ३ । २ आ. ३० सू.)

२२६ अनुपराभ्यां कृञः ॥ १।३।७९ ॥

(सूत्रप्रयोजनाधिकरणम्)

(आक्षेपभाष्यम्)

किमर्थमिदमुच्यते ? ॥

(९६३ समाधानवार्तिकम् ॥ १ ॥)

॥ * ॥ परस्मैपदप्रतिषेधात्कृञादिषु विधानम् ॥ * ॥

(भाष्यम्) परस्मैपदप्रतिषेधात्कृञादिषु परस्मैपदं विधीयते । प्रतिषिद्ध्यते तत्र परस्मैपदम् "स्वरितञितः कर्त्रभिप्राये क्रियाफले" आत्मनेपदं भवतीति ॥

(उद्द्योतः) अनुपराभ्यां ॥ ७९ ॥ भाष्ये प्रतिषिध्यते तत्र परस्मैपदमिति । स्वरितञित आत्मनेपदमिति प्राप्तस्य पुनर्विधानेनार्थादन्यन्नेत्यवगतेरिति भावः ॥ अत एव प्रतिषिध्यत इत्युक्त्वाऽग्रे कर्त्रभिप्राये क्रियाफले आत्मनेपदं भवतीत्युक्तिः संगच्छते ॥

(भाष्यम्) अस्ति प्रयोजनमेतत् । किं तर्हीति ॥

(आत्मनेपदवारणाधिकरणम्)

(९६४ आक्षेपवार्तिकम् ॥ २ ॥)

॥ * ॥ तत्रात्मनेपदप्रतिषेधोऽप्रतिषिद्धत्वात् ॥ * ॥

(भाष्यम्) तत्रात्मनेपदस्य प्रतिषेधो वक्तव्यः । किं कारणम्? । अप्रतिषिद्धत्वात् । नह्यात्मनेपदं प्रतिषिद्ध्यते । किं तर्हि? । परस्मैपदमनेन विधीयते ॥

(प्रदीपः) अनुपराभ्याम् ॥ ७९ ॥ तत्रात्मनेपदप्रतिषेधइति । अयमभिप्रायः । अशेषत्वात्कृञः पूर्वेण नियमादप्राप्तं परस्मैपदमनेन प्रतिप्रसूयते इति अनुपरापूर्वात् करोतेर्मौलेन विधिवाक्येन आत्मनेपदपरस्मैपदप्रसङ्गः ॥ विधीयत इति । नियमापाकरणद्वारेण प्रतिप्रसूयते इत्यर्थः ॥

(उद्द्योतः) ननु तिबादिसूत्रेण सामान्यतः प्राप्तानां स्वरितञित इतिनियमे तदपवादतयाऽनेन परस्मैपदविधानेन कात्मनेपदमाप्यते कर्त्रभिप्रायादावनेन परस्मैपदविधानात् । अन्यत्र शेषादिति नियमेन व्यावर्तितत्वादत आह—अयमभिप्राय इति । तदपवादत्वापेक्षया कर्तृगामिक्रियाफलादावेव तिसस्मीत्यस्य प्रतिप्रसवविधौ लाघवादिति भावः ॥ प्रतिप्रसूयत इति । क्रमेण नियम इति पक्ष इयं शङ्केत्यर्थः ॥ मौलेन, सर्वेषां मूले स्थितेन तिसस्मीत्यनेन ॥

(९६५ समाधानवार्तिकम् ॥ ३ ॥)

॥ * ॥ न वा द्युतादिभ्यो वावचनात् ॥ * ॥

(भाष्यम्) न वा एष दोषः । किं कारणम्? । द्युतादिभ्यो वावचनात् । यदयं द्युतादिभ्यो वावचनं करोति तज्ज्ञापयत्याचार्यः—न परस्मैपदविषये आत्मनेपदं भवतीति ॥

(प्रदीपः) नवेति । द्युद्भ्यो लुङीत्यत्रान्तरेणापि वावचनानुवृत्तिं परस्मैपदप्रतिप्रसवादुभयस्मिन्सिद्धे स्वरितत्वेन वावचनानुवृत्तिर्लिङ्गं परस्मैपदप्रतिप्रसवे आत्मनेपदाभावस्य ॥

(उद्द्योतः) वा क्यष इत्यतो द्युद्भ्य इत्यत्र वाग्रहणानुवृत्तिः ॥

(९६६ न्यासान्त्य समाधानवार्तिकम् ॥ ४ ॥)

॥ * ॥ आत्मनेपदनियमे वा प्रतिषेधः ॥ * ॥

(भाष्यम्) आत्मनेपदनियमे वा प्रतिषेधो वक्तव्यः । 'स्वरितञितः कर्त्रभिप्राये क्रियाफले' आत्मनेपदं भवति, कर्तरि अनुपराभ्यां कृञो नेति ।

(प्रदीपः) आत्मनेपदनियमे वेति । साक्षादात्मनेपदनिषेधे क्रियमाणे मूलविधेः प्रतिप्रसवाशङ्का न भवति ॥

(उद्द्योतः) नन्वनेन निषेधेन नियमापाकरणेपि पुनर्मूलविधेः प्रवृत्त्याशङ्का तदवस्थैवेत्यत आह—साक्षादिति । तन्निषेधे हि शेषत्वात् शेषादिनियमात्तन्नियमप्रसङ्ग इति भावः ॥

(तदस्याक्षेपभाष्यम्)

सिद्ध्यति । सूत्रं तर्हि भिद्यते ॥

(सिद्धान्तिभाष्यम्)

यथान्यासमेवास्तु ॥

(आक्षेपस्मारणभाष्यम्)

ननु चोक्तं * तत्रात्मनेपदप्रतिषेधोऽप्रतिषिद्धत्वात् * इति ॥

(समाधानभाष्यम्)

परिहृतमेतत् * न वा द्युतादिभ्यो वावचनात् * इति ॥ अथ वा एवं तावदयं प्रष्टव्यः—स्वरितञितः कर्त्रभिप्राये क्रियाफले आत्मनेपदं भवतीति परस्मैपदं कस्मान्न भवति । आत्मनेपदेन बाध्यते । यथैव तर्ह्यात्मनेपदेन परस्मैपदं बाध्यते, एवं परस्मैपदेनाप्यात्मनेपदं बाधिष्यते ॥ अनुपराभ्याम् ॥ ७९

(प्रदीपः) यथैव तर्हीति । आत्मनेपदापवादः परस्मैपदं विधीयते, न तु प्रतिप्रसवद्वारेणानियमः प्रतिपाद्यते इति भावः ॥ ७९ ॥

(उद्द्योतः) विधीयत इति । न क्रमेण नियमः किं तु सर्वं प्रकरणं युगपदेव नियामकमिति भावः । अनेन नियमानां विधिमुखेन प्रवृत्तिः सामान्यशास्त्रसंकोचकता चेति ध्वनितम् । भाष्येप्यात्मनेपदेन परस्मैपदं बाध्यत इत्युक्त्या विधिमुखप्रवृत्तिः सूचिता, निषेधमुखेन प्रवृत्तौ हि तन्निषेधस्य शाब्दत्वाद् बाध्यते इत्युक्तिरसङ्गतैव स्यात् ॥ ७९ ॥

(१६० परस्मैपदनियमसूत्रम् १।३।२ आ. ३१ सू.)

२३३ बुधयुधनशजनेङ्प्रुद्रुस्रुभ्यो णेः ॥ ८७ ॥

(आक्षेपभाष्यम्)

बुधादिषु येऽकर्मकास्तेषां ग्रहणं किमर्थम्? ॥

(समाधानभाष्यम्)

बुधादिषु येऽकर्मकास्तेषां ग्रहणं सकर्मकार्थमचित्तवत्कर्तृकार्थं वा ॥ बुधयुधनश ॥ ८६ ॥

(प्रदीपः) बुधयुधनशजनेङ् ॥ ८६ ॥ सकर्मकार्थमिति । अकर्मका अपि धातवः सोपसर्गा अनुपसर्गा वा अर्थान्तरवृत्तित्वे सति सकर्मका भवन्ति । अन्तर्भावितण्यर्था वा प्रयोज्यकर्मणा ॥ अचित्तवत्कर्तृकार्थं वेति । वा शब्दश्चार्थे ॥ तेनाकर्मकाणामचित्तवत्कर्तृकार्थं ग्रहणम् । चित्तवत्कर्तृकाणां तु सकर्मकार्थमित्यर्थः ॥ ८६ ॥

(उद्द्योतः) बुधयुध ॥ ८६ ॥ उत्तरसूत्रेण सिद्धिमाशङ्क्य परिहरति—भाष्ये बुधादिष्विति । नन्वकर्मकाणां ग्रहणं सकर्मकार्थमिति विरुद्धमत आह—अकर्मका अपीति । प्रकारत्रयेण तेषां सकर्मकत्वमिति भावः । नन्वकर्मकाणां सकर्मकतादशायामिवाप्राप्तस्याविशेषाद् अचित्तवत्कर्तृकतायामपि विध्यर्थत्वसंभवाद्वाकारोऽनुपपन्न इत्यत आह—चार्थे इति ॥ अचित्तवत्कर्तृकार्थमिति अचित्तवत्कर्तृकाकर्मकार्थमित्यर्थः ॥ ८६ ॥

(१६१ परस्मैपदनियमसूत्रम् ।१।३ ।२ आ. ३२ सू.)

२३५ अणावकर्मकाच्चित्तवत्कर्तृकात् ॥ ८८ ॥

(चुरादिभ्योऽपि परस्मैपदसाधनाधिकरणम्)

(१६७ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ अणावकर्मकादिति चुरादिणिचो ण्यन्तात्परस्मैपदवचनम् ॥ * ॥

(भाष्यम्) **अणावकर्मकादिति चुरादिणिचो ण्यन्तात्परस्मैपदं वक्तव्यम् । इहापि यथा स्यात् चेतयमानं प्रयोजयति चेतयति ॥**

(प्रदीपः) अणावकर्मकात् ॥ ८८ ॥ अणाविति णिमात्रस्य पर्युदासात् चुरादिण्यन्तो योऽकर्मकश्चित्तवत्कर्तृकश्च तस्माद्धेतुमण्ण्यन्तादप्राप्तं परस्मैपदमित्यणौ इति वार्तिकमारब्धम् ॥ चुरादिणिचो ण्यन्तादिति । चुरादिण्यन्ताद्द्वितीयहेतुमण्ण्यन्तादित्यर्थः ॥

(उद्द्योतः) अणाव ॥ ८८ ॥ ननु यतो णेरात्मनेपदं ततः प्रागवस्थाऽणिपदग्राह्येति न दोषोऽत आह—णिमात्रेति । प्रत्यासत्तिमजानानस्य शङ्केत्यर्थः । चुरादिणिचो ण्यन्तादिति सामानाधिकरण्ये वैयधिकरण्ये चानन्वयोऽत आह—द्वितीयेति ॥

(प्रत्याक्षेपभाष्यम्)

यदि तर्ह्यत्रापीष्यते अणिग्रहणमिदानीं किमर्थं स्यात्? ॥

(प्रत्याक्षेपसमाधानभाष्यम्)

अकर्मकग्रहणमण्यन्तविशेषणं यथा विज्ञायेत ॥

(प्रदीपः) अकर्मकग्रहणमिति । अणावित्यस्य यद्यपि प्रयोजनमस्ति 'आरोहयमाणं प्रयुङ्क्ते आरोहयते' इत्यत्रानेन मा भूत्परस्मैपदम् । तथापि प्रयोजनान्तरमप्यस्तीति भाष्यकारो दर्शयति ॥

(उद्द्योतः) आरोहयमाणमिति । निवृत्तप्रेषणचतुर्थकक्षेयम् । ततो हेतुमण्णिच् ॥ प्रयोजनान्तरमपीति । वस्तुतस्तादृशप्रयोगानभिधानमिति भाष्याशय इत्यन्ये ॥

(प्रत्याक्षेपभाष्यम्)

अथाक्रियमाणे अणिग्रहणे अकर्मकग्रहणं कस्य विशेषणं स्यात्? ॥

(प्रत्याक्षेपसमाधानभाष्यम्)

णेरिति वर्तते । ण्यन्तविशेषणं स्यात् ॥ तत्र को

दोषः? । इहैव यथा स्यात्—चेतयमानं प्रयोजयति चेतयति । इह न स्यात्—आसयति, शाययतीति, ।

(९६८ समाधानवार्तिकम् ॥ २ ॥)

॥ * ॥ सिद्धं त्वतस्मिन् णाविति वचनात् ॥ * ॥

(भाष्यम्) सिद्धमेतत् । कथम् । अतस्मिन् णौ यः अकर्मकस्तस्मादिति वक्तव्यम् ।

(प्रदीपः) सिद्धं त्वतस्मिन्निति । तच्छब्देन हेतुमण्णिजिर्दिश्यते । तस्यैव पूर्वसूत्र उपादानाद्बुधादिभ्यस्तस्यैव संभवात् । तेनायमर्थः—अहेतुमण्ण्यन्तो योऽकर्मकश्चित्तवत्कर्तृकश्च तस्माद्धेतुमण्ण्यन्तात्परस्मैपदं भवति । तेन चेतयतीत्यत्रापि सिद्ध्यति ॥

(उद्द्योतः) तस्यैवेति । यद्यपि यस्माण्णेः प्रागिति वक्ष्यमाणरीत्या हेतुमण्णिरिति लभ्यं तथाप्ययं भावस्तथा सत्याद्यपाद्वेति विकल्पितणिच्यण्यन्तसंभवेन ततश्चुरादिण्यन्तादपि परस्मैपदं यथा स्यादिति ॥

(आक्षेपभाष्यम्)

सिद्ध्यति । सूत्रं तर्हि भिद्यते ॥

(समाधानभाष्यम्)

यथान्यासमेवास्तु ॥

(आक्षेपकारणभाष्यम्)

ननु चोक्तम् #अणावकर्मकादिति चुरादिणिचो ण्यन्तात्परस्मैपदवचनम्# इति ।

(समाधानभाष्यम्)

नैष दोषः । अणाविति कस्येदं णेर्ग्रहणम्? । यस्माण्णेः प्राक्कर्म कर्ता वा विद्यते । न चैतस्माण्णेः प्राक्कर्म कर्ता वा विद्यते ॥ अणावकर्मकात् ॥ ८८ ॥

(प्रदीपः) यस्माण्णेरिति । एतच्च णेरणावित्यत्रोक्तं तदेव पुनः प्रकृतोपयोगाद्भाष्यकारेण स्मारितम् ॥ ८८ ॥

(उद्द्योतः) उत्तरभाष्यस्य त्वयं भावः—क्वचित्तथा अण्यन्तासंभवेपि चुरादिणिच्त्वावच्छेदेन न संभवति । हेतुमण्णिच्त्वावच्छेदेन तु संभवत्यण्यन्ततेति स एव गृह्यते इति ॥ ८८ ॥

(१६२ परस्मैपदनियमबाधकसूत्रम् १।३।२ आ. ३३ सू.)

२३९ न पादम्याङ्यमाङ्यसपरिमुहरुचिनृतिवदवसः ॥ ८९ ॥

(९६९ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ पादिषु धेट उपसंख्यानम् ॥ * ॥

(भाष्यम्) पादिषु धेट उपसंख्यानं कर्तव्यम् ॥ धापयेते शिशुमेकं समीची ॥ न पादम्या० ॥ ८९ ॥

(प्रदीपः) न पादम्याङ्यमाङ्यसपरिमुहरुचिनृतिवदवसः ॥ ८९ ॥ समीची इति । प्रथमाद्विवचने वा छन्दसीति पूर्वसवर्णदीर्घः ॥ ८९ ॥

(उद्द्योतः) न पाद ॥ ८९ ॥ छन्दसीति । सुपां सुलुगिति लुकोप्युपलक्षणमिदम् ॥ ८९ ॥

(१६३ परस्मैपदनियमसूत्रम् ॥ १ । ३।२ आ. ३४ सू.)

२४० लुटि च कृपः ॥ ९३ ॥

(आक्षेपभाष्यम्)

किमर्थश्चकारः? ॥

(समाधानभाष्यम्)

स्यसनोरित्येतदनुकृष्यते ॥

(उद्द्योतः) लुटि च ॥ ९३ ॥ भाष्ये अनुकृष्यत इति । वृद्भ्यः स्यसनोरित्यनेन तु न सिद्धिस्तत्र चतुर्णामेव ग्रहणादिति भावः ।

(प्रत्याख्यानभाष्यम्)

यदि तर्हि नान्तरेण चकारमनुवृत्तिर्भवति, "शुद्भ्यो लुङीत्यत्रापि चकारः कर्तव्यः विभाषेत्यनुकर्षणार्थः, । अथेदानीमन्तरेणापि चकारमनुवृत्तिर्भवति, इहापि नार्थश्चकारेण । एवं सर्वे चकाराः प्रत्याख्यायन्ते ॥ लुटि च कृपः ॥ ९३ ॥

इति श्रीमद्भगवत्पतञ्जलिविरचिते व्याकरणमहाभाष्ये प्रथमाध्यायस्य तृतीये पादे द्वितीयमाह्निकम् ॥ पादश्च तृतीयः समाप्तः ॥

(प्रदीपः) लुटि च कृपः ॥ ९३ ॥ स्वरितत्वादनुवृत्त्या चशब्दप्रतिपाद्यस्यार्थस्य सिद्धत्वाद्भाष्यकारः सर्वानेव चशब्दान्प्रत्याचष्टे ॥ ९३ ॥

इत्युपाध्यायजैयटपुत्रकैयटकृते महाभाष्यप्रदीपे प्रथमस्याध्यायस्य तृतीये पादे द्वितीयमाह्निकम् ॥ पादश्च तृतीयः समाप्तः ॥

(उद्द्योतः) भाष्यकार इति । न च चकारेण स्पष्टा प्रतिपत्तिः स्वरितत्वं तु व्याख्यानसापेक्षमिति वाच्यम् । चलेपि चे समुच्चेतव्यविशेषप्रतिपत्तये तदपेक्षायास्तुल्यत्वादिति भावः ॥ सर्वे चकारा इति । अनुवृत्तिफलका इत्यर्थः । तेनाटश्चेति चस्य पुनर्विधानार्थत्वपरभाष्येणाविरोधः ॥ ९३ ॥

इति शिवभट्टसुतसतीगर्भजनागोजीभट्टकृते भाष्यप्रदीपोद्द्योते प्रथमाध्यायस्य तृतीये पादे द्वितीयमाह्निकम् ॥ पादश्च समाप्तस्तृतीयः ॥ छ ॥ शुभम् ॥

प्रथमाध्यायस्य चतुर्थपादे प्रथमाह्निकम्

(१६४ नियमसूत्रम् ॥ १ । ४ । १ आ. १ ॥)

२४१ आकडारादेका संज्ञा ॥ १।४।१ ॥

(सूत्रप्रयोजनाधिकरणम्)

(आक्षेपभाष्यम्)

किमर्थमिदमुच्यते ? ॥

(प्रदीपः) **आकडारादेका ॥ १ ॥ किमर्थमिति ।** आकडारात्परा निरवकाशा च संज्ञेष्यते । तत्रान्तरेणापि सूत्रं **विप्रतिषेधे परमिति** वचनात्परा भविष्यति न पूर्वा । निरवकाशापि हि सावकाशां विशेषविहितत्वादेव बाधित्वा भविष्यति कौण्डिन्ये दधिदानमिव तक्रदानमिति प्रश्नः ॥

(उद्द्योतः) श्रीगणेशाय नमः ॥ **आकडारात् ॥ १ ॥** नन्वविरुद्धानां संज्ञानां विषये विरोधमूलकविप्रतिषेधशास्त्राप्रवृत्तेरस्य कैमर्थ्यमनुपपन्नमत आह—**आकडारादिति ।** अविरोधमजानतः शङ्केति भावः ॥ निरवकाशस्थले त्वविरोधं जानतोपि शङ्केत्याह—**विशेषे इति ।** ननु विरोधादपीत्येवकारार्थः ॥

(९७० समाधानवार्तिकम् ॥ १ ॥)

॥ * ॥ अन्यत्र संज्ञासमावेशान्नियमार्थं वचनम् ॥ * ॥

(भाष्यम्) **अन्यत्र संज्ञासमावेशो भवति ॥ कान्यत्र ?। लोके व्याकरणे च । लोके तावत्—'इन्द्रः शक्रः पुरुहूतः पुरंदरः' 'कन्दुः कोष्ठः कुसूल' इति एकस्य द्रव्यस्य बह्व्यः संज्ञा भवन्ति । व्याकरणेपि कर्तव्यं हर्तव्यमित्यत्र प्रत्ययकृत्कृत्यसंज्ञानां समावेशो भवति । पाञ्चालः वैदेहः वैदर्भ इति प्रत्ययतद्धिततद्राजसंज्ञानां समावेशो भवति ॥ अन्यत्र संज्ञासमावेशादेतस्मात्कारणात् आकडारादपि संज्ञानां समावेशः प्राप्नोति । इष्यते चैकैव संज्ञा स्यादिति । तच्चान्तरेण यत्नं न सिद्ध्यतीति नियमार्थं वचनम् । एवमर्थमिदमुच्यते ॥**

(प्रदीपः) **अन्यत्रेति ।** विप्रतिषेधे परं कार्यमुच्यते । न च संज्ञानां विरोधः, युगपत्प्रवृत्तिसंभवात् ॥ न च बाध्यबाधकभावः । भिन्नफलत्वाद्विरोधाभावाच्च ॥ दधितक्रयोरभिन्नं फलमोदनसेक इति तयोर्बाध्यबाधकभावः । **अष्टाश्रिर्यूपो भवति । वाजपेयस्य चतुरश्र** इत्यष्टाश्रित्वचतुरश्रत्वयोस्तु विरोधात् ॥ **इन्द्रः शक्र इति ।** यद्यप्यत्र फलभेदो नास्ति तथापि समावेशोस्तीति प्रतिपादनायोदाहरणोपन्यासः ॥ **कर्तव्यमिति ।** प्रत्ययसंज्ञायाः प्रयोजनं धातोरङ्गसंज्ञा, कृत्संज्ञायाः प्रयोजनं प्रातिपदिकत्वं, कृत्यसंज्ञायास्तयोरेवेति कर्मणि विधानम् ॥

(उद्द्योतः) **न च संज्ञानामिति ।** इन्द्रः शक्रः कुत्कुत्य इति च संज्ञानां लोकशास्त्रयोर्युगपत्प्रवृत्तिदर्शनादिति भावः ॥ **न चेति ।** अनवकाशत्वप्रयुक्त इत्यर्थः ॥ एकफलकत्वे सहानवस्थानलक्षणविरोधे वाऽनवकाशं बाधकं न चैतदुभयमप्यत्रेत्याह—**भिन्नफलत्वादिति ।** वस्तुतः समावेशदर्शनादेवाविरोधो विशेषत्वेप्यबाधकत्वमिति भाष्याशयः । कैयटोक्तमेकफलत्वं विरोधश्च व्यभिचरितौ । अत एवाचि रादेशेन नुटो बाधमाशङ्क्य न तिसृचतसृ-ज्ञापकेन समाहितं सप्तमे भाष्ये । तादृशस्थले एकफलत्वाभावः स्पष्ट एव । तक्रेण दध्नो बाधनमविरोधे आस्वादरूपफलभेदे च दृष्टमित्यलम् । कृते तु सूत्रेऽन्यत्र बलवत्त्वेन दृष्टतया व्यवस्थाकाङ्क्षायां परत्वानवकाशत्वाभ्यां सेत्याहुः ॥ **यद्यपीति ।** एवं च दृष्टान्तो विषम इति भावः ॥ **उदाहरणेति ।** फलभेदेपि यदि समावेशः किमु वक्तव्यं तद्भेद इति दृष्टान्ततेति भावः । नन्विन्द्रादीनामैश्वर्यशक्तिमत्त्वबहुधाशानपूर्दारणानि प्रवृत्तिनिमित्तानीति कथमेते संज्ञाशब्दाः शब्दप्रवृत्तिनिमित्तको हि स इति चेन्न । सत्यपि योगे रूढिमात्रेण संज्ञाशब्दत्वमिति भगवतोऽभिप्रायात् ॥ **कर्मणि विधानमिति ।** एवं च फलभेदादविरोधाच्च न बाध इति कैयटाशयः ॥

(काकुभाष्यम्)

अस्ति प्रयोजनमेतत् । किं तर्हीति ।

(सूत्रपाठनिर्णयाधिकरणम्)

(आक्षेपभाष्यम्)

कथं त्वेतत्सूत्रं पठितव्यम् किम् "आकडारादेका संज्ञा" इति, आहोस्वित् "प्राक्कडारात्परं कार्यम्" इति ? ॥

(प्रत्याक्षेपभाष्यम्)

कुतः पुनरयं संदेहः ? ।

(प्रत्याक्षेपसमाधानभाष्यम्)

उभयथा ह्याचार्येण शिष्याः सूत्रं प्रतिपादिताः । केचिद् "आकडारादेका संज्ञा" इति । केचित् "प्राक्कडारात्परं कार्यम्" इति ।

(प्रदीपः) **उभयथेति ।** तत्र गुणदोषविचारः कर्तव्य इत्यर्थः । तत्रैका **संज्ञेत्यस्मिन्पाठे** क्वचित्संज्ञासमावेशार्थो यत्नः कर्तव्यः । **परं कार्यमित्यस्मिंस्तु** पाठे समावेशः सिद्ध्यति । अत्र हि पाठे अयमर्थः प्राक्कडारात्संज्ञाख्यं कार्यं परं भवतीति । संज्ञाप्रकरणात्संज्ञैवात्र सूत्रे कार्यशब्देन विवक्षिता । तत्र यस्याः संज्ञायाः परस्याः पूर्वया बाधः प्राप्नोति, सा परानेन भाव्यते इति विध्यर्थं सूत्रं भवति न नियमार्थम् । एतदेव च परसंज्ञाविधानं ज्ञापकमत्र प्रकरणे संज्ञानां बाध्यबाधकभा-

वस्य । तेन परयानवकाशया सावकाशा पूर्वा बाध्यते द्वयोश्च सावकाशयोर्विप्रतिषेधे परया पूर्वा बाध्यत इत्येतदत्र वस्तुतत्त्वम् ॥

(उद्द्योतः) ननूभयथा पाठनिर्णये कथं संदेहोऽत आह—गुणदोषेति । किं संभवमात्रेण द्विधा पाठोऽथास्वरसादिति विवेक्तुं तद्विचारः कार्य इति भावः ॥ यत्नः । ज्ञापकाश्रयणचकारादिरूपः । यद्यपि परं कार्यमिति पाठेपि सूत्राणामन्यथा पाठः कार्यस्तथापि तत्र न वर्णगौरवं नापि प्रतिपत्तिगौरवमिति न स दोष इति भावः ॥ कार्यशब्देनेति । संज्ञेत्येव तु नोक्तमुत्तरत्रानन्वयात् । यद्यप्यन्यान्यपि कार्याण्यत्र सन्ति वचनपुरुषनियमपूर्वनिपातादयस्तथापि तेषां केनापि बाधप्रसक्त्यभावाद्बाधितप्रवृत्तये चैतत्सूत्रसत्त्वाच्छाम इति भावः ॥ पूर्वया अनवकाशया ॥ न नियमार्थमिति । आद्यपाठे त्वेकैव संज्ञा न द्वितीयेति नियमो विध्यर्थत्वासंभवात् । अत्र च विध्यर्थत्वसंभवेन नियमो न युक्त इति भावः ॥ ननु पर्यायेण प्रवृत्त्या पूर्वस्यापि चारितार्थ्यसंभवेन संज्ञानां विरोधाभावेन चोभयोः प्रसक्तावत्रापि पाठे नियम एव स्यादत आह—एतदेवेति । नियमेऽनुवाददोषापत्त्या वरं बाधकत्वकल्पनद्वारा विधित्वमिति भावः ॥ विप्रतिषेधे इत्यस्य दृष्टबाधयेति शेषः ॥

(आक्षेपभाष्यम्)

कश्चात्र विशेषः? ।

(९७१ "एका संज्ञा" इति पाठे गौरवाक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ तत्रैकसंज्ञाधिकारे तद्वचनम् ॥ * ॥

(भाष्यम्) तत्रैकसंज्ञाधिकारे तद्वक्तव्यम् । किम्? ॥ एका संज्ञा भवतीति ॥

(परंकार्यमितिन्यासेपि गौरवभाष्यम्)

ननु च यस्यापि परंकार्यत्वं तेनापि परग्रहणं कर्तव्यम् ॥

(गौरवाभावभाष्यम्)

परार्थं मम भविष्यति "विप्रतिषेधे च" इति ॥

(एकासंज्ञेतिन्यासेपि गौरवपरिहारभाष्यम्)

ममापि तर्ह्येकग्रहणं परार्थं भविष्यति—"सरूपाणामेकशेष एकविभक्तौ" इति ॥ संज्ञाधिकारश्चायम् । तत्र किमन्यच्छक्यं विज्ञातुमन्यदतः संज्ञायाः । तत्रैतावद्वाच्यम्—'आकडारादेका' ॥ किम्? । एका संज्ञा भवतीति ॥

(प्रदीपः) आकडारादेकेति । संज्ञाप्रकरणादेकेति स्त्रीलिङ्गनिर्देशः संज्ञाशब्दानुच्चारणेपि न विरुद्धः । अस्माच्च सूत्रात्परं सरूपाणामेकशेष एकविभक्ताविति प्रकरणं कर्तव्यम् । तत्रैकेत्यस्य शब्दस्य स्वरितत्वादनुवृत्तौ लिङ्गविपरिणामेन संबन्धे सत्येकग्रहणं पुनर्न कर्तव्यं भवतीत्यर्थः ॥

(उद्द्योतः) भाष्ये परार्थमिति । अन्यत्राप्यकरणार्थमित्यर्थः । परार्थं यत्त्वया कृतं तदेव मयात्र कृतं भविष्यतीत्यर्थः ॥ ननु विशेष्यवाचिपदासंनिधाने नपुंसकमेव प्रयोक्तुमुचितं, संज्ञापर्यायनामादिशब्दानामपि विशेष्यत्वसंभवाच्चात आह—संज्ञेति । प्रचुरप्रसिद्धेः संज्ञाशब्द एव प्रकरणादुपतिष्ठत इत्यर्थः ॥ ननु सरूपाणामित्यस्यातिक्रान्तत्वात्कथं तदर्थतास्येत्यत आह—अस्माच्चेति । एकसंज्ञाधिकारोत्तरमित्यर्थः ॥ लिङ्गविपरिणामेनेति । भावसाधने शेषशब्दे विभक्तिविपरिणामेनेत्यपि बोध्यम् । बहुयोगव्यवधानाद् यत्त्वया परार्थं कृतं तदेव ममात्र बुद्धिस्थं भविष्यतीत्यर्थकतया तत्रत्यमत्रानुवर्तते इत्येवं भाष्यं न व्याख्यातम् ॥ नन्वेवमपि संज्ञेत्यधिकं कार्यमेवेत्यत आह—संज्ञाधिकारश्चेति ॥ किमिति । प्रश्नः ॥ एका संज्ञेत्याद्युत्तरम् ॥ प्रश्ने सामान्ये नपुंसकम् ॥

(९७२ एकसंज्ञाधिकारे दूषणान्तरवार्तिकम् ॥ २ ॥)

॥ * ॥ अङ्गसंज्ञया भपदसंज्ञयोरसमावेशः ॥ * ॥

(भाष्यम्) अङ्गसंज्ञया भपदसंज्ञयोः समावेशो न प्राप्नोति । सार्पिष्कः । बार्हिष्कः । याजुष्कः । धानुष्कः । बाभ्रव्यः । माण्डव्य इति । अनवकाशे भपदसंज्ञे अङ्गसंज्ञां बाधेयाताम् ॥

(प्रदीपः) सार्पिष्क इति । असत्यामङ्गसंज्ञायामङ्गस्योच्यमाना वृद्धिर्न स्यात् । अङ्गसंज्ञा च कर्तव्यमित्यादिषु सावकाशा यत्र पूर्वस्य भपदसंज्ञे न स्तः ॥ ननु तद्धितेष्वचामादेः किति चेत्यङ्गस्य वृद्धिविधानसामर्थ्यात्समावेशो भविष्यति । नैतदस्ति । वचनादनङ्गस्यापि वृद्धिः स्यात् । ततश्च देवदत्तो गार्ग्य इत्यत्रापि यञि परतो देवदत्तादेः समुदायस्यापि वृद्धिः प्रसज्येत । यथा डित्यभस्याप्यनुबन्धकरणसामर्थ्यात्कुमुद्वानित्यादौ टिलोपः ॥

(उद्द्योतः) सर्पिःशब्दादार्हीयष्ठक् तदस्य पण्यमिति वा । इसन्तत्वात्कः ॥ तत्राङ्गसंज्ञाभावे किं स्यादत आह—असत्यामिति । अनङ्गस्यापीति । यद्यपीष्टानुरोधात्समावेशोपि ज्ञापयितुं शक्यस्तथापि लक्षणैकशरणानामिष्टानिष्टे दुर्ज्ञेये इति भावः ॥ देवदत्तो गार्ग्य इति । वाक्यसंस्कारपक्षे इदम् । प्रत्ययग्रहणपरिभाषया वृद्धिवारणं शक्यमिति चिन्त्यम् ॥ कुमुद्वानिति । उम्तुप् । सिद्धान्तस्त्वित एव ज्ञापकात्समावेश इति ॥

(परंकार्यत्वेसमावेशसाधकपूर्वपक्षभाष्यम्)

परवचने हि नियमानुपपत्तेरुभयसंज्ञाभावः ।

(व्याख्याभाष्यम्)

यस्य पुनः परंकार्यत्वं नियमानुपपत्तेस्तस्योभयोः

संज्ञयोर्भावः सिद्धः ॥ कथम् ?। पूर्वे तस्य भपदसंज्ञे परा अङ्गसंज्ञा ॥ कथम् ?। एवं स वक्ष्यति—"यस्मात्प्रत्ययविधिस्तदादि सुप्तिङन्तं पदम्" "नः क्ये" सिति च" "स्वादिष्वसर्वनामस्थाने" "यचि भम्" तस्यान्ते "प्रत्ययेऽङ्गम्" इति । तत्रारम्भसामर्थ्याच्च भपदसंज्ञे । परंकार्यत्वाच्चाङ्गसंज्ञा भविष्यति ॥

(प्रदीपः) **परंकार्यत्वमिति** परंकार्यमित्येतदेकदेशस्यानुकरणं परंकार्यशब्दस्तस्यानुकार्येणार्थेनार्थवत्त्वात्प्रातिपदिकत्वात्तद्धितोत्पत्तिः ॥

(उद्द्योतः) परंकार्यत्वमित्यत्र सुबन्तसमुदायात्कथं तद्धितस्तदुत्पत्तावपि कथं पूर्वपदे विभक्तिश्रवणमत आह—**परंकार्येति** । शब्दस्य भावश्चार्थः । स चैकदेशद्वारैतत्सूत्रार्थरूपः । अनुवादेऽर्थविशेषणकशब्दस्वरूपप्रतीतेरिति भावः ॥

(असमावेशदूषणबाधकभाष्यम्)

ननु च यस्याप्येकसंज्ञाधिकारस्तस्याप्यङ्गसंज्ञापूर्विके भपदसंज्ञे ॥ कथम् ?। अनुवृत्तिः क्रियते ॥

(प्रदीपः) **अनुवृत्तिः क्रियते इति** । ततस्तत्पूर्वकत्वं लभ्यते । अङ्गं सद्भपदसंज्ञमित्यर्थः ॥

(उद्द्योतः) **तत इति** । अनुवर्त्तमानस्यापि विधिकोटौ निवेशादिति भावः ॥ **अङ्गं सदिति** । स्वादिषु यदङ्गं तत्पदमिति व्याख्यानेनानुवादसामर्थ्यादङ्गपदत्वयोः समावेश इति भावः ॥

(असमावेशदूषणसाधकभाष्यम्)

पर्यायः प्रसज्येत । एका संज्ञेति वचनान्नास्ति यौगपद्येन संभवः ॥

(प्रदीपः) अत्रोत्तरमाह—**पर्यायः प्रसज्येतेति** । एका संज्ञेति वचनादङ्गसंज्ञाया नित्ये बाधे प्राप्ते पर्यायार्थानुवृत्तिः स्यात् । एवं नियमो न बाधितो भवति अनुवृत्तिश्च सफला भवति ॥ ननु **न पदान्ते**त्यत्र सूत्रे भाष्यकारेणोक्तं वेतस्वानित्यस्य सिद्धये **यथैवान्यानि पदकार्याण्युपप्लवन्ते रुत्वं जश्त्वं च एवमिदमप्युपप्लोष्यते भसंज्ञा नामेति** । तत्र च पदं सद्भसंज्ञं भवतीति विज्ञायते । भसंज्ञायां पदसंज्ञानुवृत्तावपि भसंज्ञया पदसंज्ञाया बाधः पदकार्यनिवृत्तयेऽभ्युपगन्तव्यः । इह त्वङ्गसंज्ञानुवृत्तौ पर्याय उक्त इति विरोधः ॥ नैष दोषः । अङ्गसंज्ञानुवृत्तेः प्रयोजनान्तराभावात्पर्याय इहोक्तः । पदसंज्ञानुवृत्तेस्तु भसंज्ञायां प्रयोजनं पदकार्यत्वं भसंज्ञाया यथा स्यादिति । ततश्च **न पदान्ते**ति स्थानिवत्त्वनिषेधादकारलोपस्य **तसौ मत्वर्थे**इति भसंज्ञायां सत्यां पदत्वप्रयुक्तरुत्वाभावे वेतस्वानिति सिद्ध्यति ॥ कथमिति चेत् । उच्यते—भसंज्ञाविधौ पदमिति वर्तते । तत्रानुवृत्तिसामर्थ्यात्पूर्वं पदसंज्ञा प्रवर्तते । तेन पदकार्ये भसंज्ञा भवति, नान्यथा । एतावदेव चानुवृत्तेः प्रयोजनम् । ततः प्रवृत्तया भसंज्ञया पदसंज्ञा बाध्यते एका संज्ञेति नियमात् ॥

(उद्द्योतः) नन्वनुवृत्तिसामर्थ्यात्समावेशोऽत आह—**एका संज्ञेति** । तदुक्तं भाष्ये **एका संज्ञेति वचनादि**त्यादि ॥ **बाध इति** । उत्सर्गापवादन्यायेनेति भावः ॥ **इह त्विति** । इहापि तथैव स्यादिति भावः ॥ **कथमिति चेदिति** । पदमित्यनुवृत्तावप्युभयोर्विधेयतया कथं भसंज्ञा पदकार्यमिति प्रश्नः ॥ **उच्यते इति** । नानेन पदसंज्ञा विधीयते किं त्वनूद्यते इति भावः ॥ **पदसंज्ञा प्रवर्त्तत इति** । तद्बुद्धिः प्रवर्त्तते इत्यर्थः ॥ अनुवादसामर्थ्यादिति भावः । इह त्वेका संज्ञेति नियमाबाधनाय विधेयतेति विशेष इति बोध्यम् ॥ वस्तुतस्तद्भाष्यमन्यार्थकं न त्वेवमर्थकमिति तत्रैव निरूपितम् ॥ नन्वनया रीत्या **परंकार्य**मिति पाठेपि ज्ञापितसंज्ञाबाधस्यात्यन्ताबाधाय पर्याय एव स्यान्न तु समावेश इति चेन्न । अनुमितप्राप्त्यपवादभूतत्वादस्याः प्राप्तेर्ज्ञापितो बाधस्तदितरपर्यवसायीति समावेशसिद्धिरित्याशयात् ॥

(१७३ एकसंज्ञाधिकारेदूषणान्तरवार्तिकम् ॥ ४ ॥)

॥ * ॥ कर्मधारयत्वे तत्पुरुषग्रहणम् ॥ * ॥

(भाष्यम्) **कर्मधारयत्वे तत्पुरुषग्रहणं कर्तव्यम्—"तत्पुरुषः समानाधिकरणः कर्मधारय" इति । एकसंज्ञाधिकार इति चोदितम् । अक्रियमाणे हि तत्पुरुषग्रहणे ह्यनवकाशा कर्मधारयसंज्ञा तत्पुरुषसंज्ञां बाधेत ॥**

(प्रदीपः) **कर्मधारयत्वइति** । एकसंज्ञावादिनं प्रत्युच्यते—त्वया कर्मधारयसंज्ञायामेकसंज्ञाधिकारे अन्यत्र वा क्रियमाणायां तत्पुरुषग्रहणं कर्तव्यम् । एकसंज्ञाधिकारे संज्ञासमावेशार्थम् । प्रदेशान्तरे तु समासान्तरस्य कर्मधारयसंज्ञाया निवृत्त्यर्थम् । मया त्वस्मिन्नेव प्रकरणे कर्मधारयसंज्ञा क्रियते समावेशश्च सिद्ध्यतीति तत्पुरुषग्रहणं न कर्तव्यं भवतीति लाघवं भवति ॥

(उद्द्योतः) ननु बहुव्रीहेः संज्ञानिवृत्तये तत्र तत्पुरुषग्रहणमावश्यकमत आह—**एकसंज्ञेति** । **अन्यत्र वेति** । यथान्यासमित्यर्थः ॥ **मया त्विति** । परंकार्यत्ववादिनेत्यर्थः ॥ ननु समानाधिकरणग्रहणमपि कर्त्तव्यमिति किं तत्पुरुषपदकर्त्तव्यतैव विशिष्योच्यतेऽत आह । भाष्ये—**एकसंज्ञाधिकार इति चोदितमिति** । यद्यन्यत्र सा संज्ञा तदोभयं कार्यम्, एकसंज्ञाधिकारे तत्पुरुषप्रकरणे **नवकेवलाः समानाधिकरणेने**त्युत्तरं करणे त्वधिकारादेव समानाधिकरण इति लभ्यते इति तत्कर्त्तव्यतैव नोदितेति भावः ॥ **अनवकाशेति** । यथा चानवकाशत्वाद्बहुव्रीहिसंज्ञां बाधते तथा तत्पुरुषसंज्ञामपि बाधेतेत्यर्थः ॥

(परंकार्यत्वे समावेशसिद्धिमूलभाष्यम्)

परवचने हि नियमानुपपत्तेरुभयसंज्ञाभावः ॥

(व्याख्याभाष्यम्)

यस्य पुनः परंकार्यत्वं नियमानुपपत्तेस्तस्यो-

भयोः संज्ञयोर्भावः सिद्धः ॥ कथम्? ॥ पूर्वा तस्य कर्मधारयसंज्ञा परा तत्पुरुषसंज्ञा ॥ कथम्? ॥ एवं स वक्ष्यति—"पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन कर्मधारय" इत्येवं सर्वं कर्मधारयप्रकरणमनुक्रम्य तस्यान्ते "श्रितादिभिस्तत्पुरुषः" इति तत्रारम्भसामर्थ्याच्च कर्मधारयसंज्ञा, परंकार्यत्वाच्च तत्पुरुषसंज्ञा भविष्यति ॥

(प्रदीपः) **तस्यान्ते इति** । यद्येवं समानाधिकरणस्य कथं तत्पुरुषसंज्ञा सिद्ध्यति । उच्यते—पाठक्रमादर्थक्रमो बलीयानिति पूर्वं तत्पुरुष इति कर्तव्यम् । ततो **द्वितीयाश्रितेति** । तत्पुरुष इत्यत्र च **पूर्वकाले**त्यादीनि सूत्राण्यनुवर्त्य तत्पुरुषसंज्ञा विधीयते ॥

(उद्द्योतः) **यद्येवमिति** । कर्मधारयप्रकरणान्ते **द्वितीयाश्रि**तेत्यादि पठनीयं श्रितादिमपेक्ष्य च तत्पुरुषसंज्ञा कर्तव्येति भाष्यार्थं मत्वा शङ्कयम् । यदि तु **द्वितीयाश्रिते**त्यादि कृत्वा कर्मधारयप्रकरणमनुक्रम्योपपदमतिङितिप्रकरणान्ते **श्रितादिभिस्तत्पुरुष** इत्युच्यते तदा नेयं शङ्केति ध्येयम् ॥ परं त्वत्र पक्षे श्रितादिभिरित्यस्याधिकस्य करणाद् गौरवं भवतीत्युपाध्यायोक्तमेव सम्यक् ॥ नन्वेवमपि समानाधिकरणस्य तत्पुरुषत्वं न स्यात् तत्पुरुष इत्यस्योत्तरत्रैव संबन्धादत आह—**तत्पुरुष इत्यत्र चेति** । तथा च कर्मधारयसंज्ञया तत्पुरुषत्वस्य पर्याये सिद्धे परं कार्यमिति समावेशार्थमिति भावः । अत्र पक्षे बहुव्रीहिसंज्ञाविषयेऽस्याप्रसक्तिरेवेति बोध्यम् ॥

(असमावेश दूषणबाधकभाष्यम्)

ननु च यस्याप्येकसंज्ञाधिकारस्तस्यापि तत्पुरुषसंज्ञापूर्विका कर्मधारयसंज्ञा । कथम्? । अनुवृत्तिः क्रियते ॥

(प्रदीपः) **ननु च यस्यापीति** । व्यधिकरणानां तत्पुरुषसंज्ञां विधाय समानाधिकरणस्य तत्पुरुषसंज्ञानुवृत्त्या तत्पूर्विका कर्मधारयसंज्ञा विधायिष्यते इत्यर्थः । **समावेशस्य** च कारकगवीति पुंवद्भावसमासान्तौ प्रयोजनम् ॥

(उद्द्योतः) ननु द्वितीयाध्यायस्थतत्पुरुषसंज्ञायाः प्रथमे कथमनुवृत्तिरत आह—**व्यधिकरणानामिति** । द्वितीय एव "पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन कर्मधारयः" इत्येवं कर्मधारयसंज्ञा करिष्यत इति भावः ॥ **पुंवद्भावेति** । **स्त्रियाः पुंवदिति तु न कोपधाया** इति निषिद्धमिति भावः ॥ यथान्यासे तत्पुरुषानुवादेन कर्मधारयसंज्ञाया आकडारादूबहिः कृतत्वेन समावेशसिद्धिरिति तत्त्वम् ।

(असमावेशदूषणसाधकभाष्यम्)

पर्यायः प्रसज्येत । एका संज्ञेति वचनान्नास्ति यौगपद्येन संभवः ॥

(९७४ एकसंज्ञाधिकारेदूषणान्तरवार्तिकम् ॥ ५ ॥)

॥ * ॥ तत्पुरुषत्वे द्विगुचग्रहणम् ॥ * ॥

(भाष्यम्) तत्पुरुषत्वे द्विगुचग्रहणं कर्तव्यम् । "तत्पुरुषः द्विगुश्च" इति चकारः कर्तव्यः । अक्रियमाणे हि चकारग्रहणेऽनवकाशा द्विगुसंज्ञा तत्पुरुषसंज्ञां बाधेत ॥

परवचने हि नियमानुपपत्तेरुभयसंज्ञाभावः ॥

यस्य पुनः परंकार्यत्वं नियमानुपपत्तेस्तस्योभयोः संज्ञयोर्भावः सिद्धः ॥ कथम्? । पूर्वा तस्य द्विगुसंज्ञा परा तत्पुरुषसंज्ञा ॥ कथम्? । एवं स वक्ष्यति—"तद्धितार्थोत्तरपदसमाहारे च संख्यापूर्वो द्विगुः" इत्येवं सर्वं द्विगुप्रकरणमनुक्रम्य तस्यान्ते "श्रितादिभिस्तत्पुरुषः" इति । तत्रारम्भसामर्थ्याच्च द्विगुसंज्ञा,—परंकार्यत्वाच्च तत्पुरुषसंज्ञा भविष्यति ॥

(प्रदीपः) **द्विगुचग्रहणमिति** । द्विगोः सम्बन्धिनश्चशब्दस्य ग्रहणं कर्तव्यमित्यर्थः ॥ नन्वेकसंज्ञापक्षे **द्विगुश्चेति** सर्वमेव सूत्रं कर्तव्यं तत्र किं चशब्द एव चोद्यते । तत्राहुः—**द्विगुश्चेति** सूत्रं द्वयोरपि पक्षयोर्न कर्तव्यम् । एकसंज्ञापक्षे तु **संख्यापूर्वो द्विगुश्चेति** चशब्दः समावेशार्थः कर्तव्यो न पक्षान्तर इत्येतद्वार्तिककारस्य विवक्षितम् । भाष्यमप्येवं व्याख्यायते **तत्पुरुषः द्विगुश्चेति** चकारः कर्तव्य इति **तद्धितार्थे**त्यनेन यः सङ्ख्यापूर्वः समासः स तत्पुरुषो द्विगुश्च भवतीति संज्ञाद्वयं लभत इति यावत् । एतदर्थश्चकारः कर्तव्य इत्यर्थः । अयमेवार्थः परस्तात्प्रकटीभविष्यति ॥ **तस्यान्त** इत्यादि भाष्यं पूर्ववत् क्रमविपर्ययेण व्याख्येयम् ॥

(उद्द्योतः) ननु **द्विगुश्चेति** सूत्रपाठाद् **द्विगुश्चे**त्यनुपपन्नमत आह—**द्विगोरिति** । व्याप्तिन्यायात् कडाराः कर्मधारये इत्ययमेवावधिरिति तात्पर्यम् । आ द्वन्द्वादिति नोक्तम्, द्वन्द्वश्च **प्राणी**त्यस्यावधित्वापत्तौ सम्बुद्ध्यामन्त्रितसंज्ञयोः समावेशानापत्तेः ॥ **परत्वादिति** । सर्वं द्विगुप्रकरणमनुक्रम्येत्यादिग्रन्थेन ॥ अन्ये तु चकारघटितं **द्विगुश्चेति** सूत्रं कर्तव्यमिति भाष्यार्थमाहुः । कृतमेवेति न दोष इति तत्त्वम् ॥

(असमावेशदूषणबाधकभाष्यम्)

ननु च यस्याप्येकसंज्ञाधिकारस्तस्यापि तत्पुरुषसंज्ञापूर्विका द्विगुसंज्ञा । कथम्? । अनुवृत्तिः क्रियते ॥

(असमावेशदूषणसाधकभाष्यम्)

पर्यायः प्रसज्येत । एका संज्ञेति वचनान्नास्ति यौगपद्येन संभवः ॥

(९७५ दूषणान्तरवार्तिकम् ॥ ६ ॥)

॥ * ॥ गतिदिवःकर्महेतुमत्सु च-ग्रहणम् ॥ * ॥

(भाष्यम्) गतिदिवःकर्महेतुमत्सु चग्रहणं कर्तव्यम् ॥

"उपसर्गाः क्रियायोगे" "गतिश्च" इति चकारः कर्तव्यः । अक्रियमाणे हि चकारे अनवकाशा उपसर्गसंज्ञा गतिसंज्ञां बाधेत ॥

परवचने हि नियमानुपपत्तेरुभयसंज्ञाभावः ॥

यस्य पुनः परंकार्यत्वं नियमानुपपत्तेस्तस्योभयोः संज्ञयोर्भावः सिद्धः ॥ कथम् ?। पूर्वा तस्योपसर्गसंज्ञा, परा गतिसंज्ञा । तत्रारम्भसामर्थ्याच्चोपसर्गसंज्ञा, परंकार्यत्वाच्च गतिसंज्ञा भविष्यति ॥

(प्रदीपः) गतिसंज्ञामिति । ऊर्यादिषु सावकाशामिति भावः ॥

(उद्योतः) ननु गत्युपसर्गसंज्ञयोः समानविषयत्वात्कथमुपसर्गत्वस्यैव निरवकाशत्वमत आह—ऊर्यादीति ॥ गतित्वेनैकीकृत्य सावकाशत्वाभिमानः ॥

(असमावेशदूषणबाधकभाष्यम्)

ननु च यस्याप्येकसंज्ञाधिकारस्तस्याप्युपसर्गसंज्ञापूर्विका गतिसंज्ञा ॥ कथम् ? । अनुवृत्तिः क्रियते ॥

(असमावेशदूषणसाधकभाष्यम्)

पर्यायः प्रसज्येत । एका संज्ञेति वचनान्नास्ति यौगपद्येन संभवः ॥

(दूषणबाधकभाष्यम्)

गतिसंज्ञाप्यनवकाशा वचनाद्भविष्यति ॥

(दूषणसाधकभाष्यम्)

सावकाशा गतिसंज्ञा । कोऽवकाशः ? । ऊर्यादीन्यवकाशः ॥

(दूषणबाधकभाष्यम्)

प्रादीनां या गतिसंज्ञा सानवकाशा ॥ गति ॥

(प्रदीपः) प्रादीनां या गतिसंज्ञेति । गतिश्चेत्यत्रासत्यपि चकारे समावेशः सिद्धयति । गतिरित्यत्र योगे प्रादीनामनुवृत्त्या गतिसंज्ञा विधीयते । तत्र वचनसामर्थ्यात्पर्याये लब्धे सति उपसर्गसंज्ञानुवृत्तिः समावेशार्था भविष्यतीत्यर्थः । समावेशस्य च प्रणीतमभिषिक्तमित्यत्र गतिस्वरो णत्वषत्वे च प्रयोजनम् ॥

(उद्योतः) गतिस्वरो गतिरनन्तर इति पूर्वपदप्रकृतिस्वरः ॥ उपसर्गादसमासेऽपि णत्वम् । उपसर्गात्सुनोतीति षत्वम् ॥

(द्वितीयोदाहरणसमन्वयभाष्यम्)

दिवःकर्म—"साधकतमं करणम्" "दिवः कर्म च" चकारः कर्तव्यः । अक्रियमाणे हि चकारेऽनवकाशा कर्मसंज्ञा करणसंज्ञां बाधेत ॥

परवचने हि नियमानुपपत्तेरुभयसंज्ञाभावः ॥

यस्य पुनः परंकार्यत्वं नियमानुपपत्तेस्तस्योभयोः संज्ञयोर्भावः सिद्धः ॥ कथम् ? । पूर्वा तस्य कर्मसंज्ञा, परा करणसंज्ञा ॥ कथम् ? ॥ एवं स वक्ष्यति—"दिवः साधकतमं कर्म" ॥ ततः "करणम्" । करणसंज्ञं च भवति साधकतमम् । दिव इति निवृत्तम् । तत्रारम्भसामर्थ्याच्च कर्मसंज्ञा परंकार्यत्वाच्च करणसंज्ञा भविष्यति ॥

(प्रदीपः) दिवः कर्म चेति । समावेशस्य च प्रयोजनमक्षैर्देवयते देवदत्तो यज्ञदत्तेनेति । प्रयोज्यकर्तुर्गतिबुद्धीति नियमात्कर्मसंज्ञानिवृत्तिः अणावकर्मकादिति परस्मैपदाभावश्च । यद्येवमक्षान्दीव्यतीति द्वितीया न प्राप्नोति, तृतीयया परत्वाद्बाधितत्वात् । विभक्तिद्वयं चेष्यते । कर्मसंज्ञा च सावकाशा अकर्मकव्यपदेशव्यावृत्त्यर्थत्वात् । करणसंज्ञापि देवना अक्षा इति ल्युडर्था । अत्राहुः—कार्यकालं संज्ञापरिभाषमिति पक्षोऽत्राश्रीयते । तेन कर्मणि द्वितीयेत्यत्र कार्ये यत्कर्मसंज्ञाया उपस्थानं तदनवकाशमिति द्वितीया भविष्यति । अक्षाणां देवितेत्यादौ तु कृत्प्रयोगे षष्ठ्या द्वितीयाऽपवादत्वाद्बाध्यते तृतीया तु परत्वात् ॥

(उद्योतः) दिवः कर्म चेत्यत्र संज्ञयोः समावेशेन तद्वाच्यर्थसाधकतमे शक्तिद्वयसमावेशो बोध्यते ॥ समावेशस्येति । करणत्वादक्षाणां तृतीया । कर्मत्वाच्चाकर्मकत्वाभावात् परस्मैपदाभावः । प्रयोज्येऽकर्मकत्वप्रयुक्तकर्मत्वनिवृत्तिद्वारा यज्ञदत्ते तृतीया चेति भावः। तृतीयैव चात्र शास्त्रबलाच्छक्तिद्वयबोधिकेति बोध्यम् ॥ ननु कर्मत्वविधानसामर्थ्याद् द्वितीयेत्यत आह—कर्मसंज्ञा चेति । इदमुपलक्षणं कर्मणि लकारादेरपि ॥ तृतीया त्विति । कर्तृकरणयोरित्यत्रास्योपस्थितिस्त्वकृद्योगे चरितार्थेति भावः । न च स्तोकं पाक इत्यादावपि षष्ठी स्यादिति वाच्यम् । कर्तृसादृश्यादर्थाद् अभात्वर्थकर्मण एव ग्रहणेनादोषात् । न चैवं मनसादेव इत्यादिप्रयोगः कथं, हेतुतृतीयान्तेन पचाद्यजन्तदेवशब्दस्य समासे सिद्धत्वात् ॥ केचित्तु साधकतमगतकर्मत्वशक्तिबोधेऽक्षान्दीव्यतीति प्रयोगे दृढतरं मानं चिन्त्यम् । कार्यकालपक्षेपि परत्वात्तृतीयया बाधे न्याय्ये तदनुपस्थितेरेव न्याय्यत्वात् । किं च तत्र फलाश्रयत्वविवक्षया कर्तुरिति कर्मत्वं न च तदा करणत्वमिति न दोषः । किं च क्रिति चेतिसूत्रकैयटोक्तरीत्या यथोद्देशेपि प्रधानानुरोधेन गुणानां स्वात्मभेदकल्पनस्य तुल्यतया विशिष्य कार्यकालपक्षे इत्युक्तिरनुचिता । किं च कार्यकालपक्षेऽचादिभ्यः परैव प्रगृह्यसंज्ञेत्यदसोमादि-

तिग्भाष्योक्तरीत्याऽपादानमुत्तराणि गां दोग्धि पय इत्यत्रत्यभाष्यासंगतेराकडारस्थसंज्ञानां यथोद्देशत्वमेवेति च तदुक्त्यसंगतिरित्याहुः ।

(दूषणबाधकभाष्यम्)

नन्नु च यस्याप्येकसंज्ञाधिकारस्तस्यापि करणसंज्ञापूर्विका कर्मसंज्ञा । कथम् ? । अनुवृत्तिः क्रियते ॥

(दूषणसाधकभाष्यम्)

पर्यायः प्रसज्येत । एका संज्ञेति वचनान्नास्ति यौगपद्येन संभवः ॥ दिवः कर्म ॥

(उदाहरणान्तरसमन्वयभाष्यम्)

हेतुमत् । "स्वतन्त्रः कर्ता" "तत्प्रयोजको हेतुश्च" चकारः कर्तव्यः । अक्रियमाणे हि चकारेऽनवकाशा हेतुसंज्ञा कर्तृसंज्ञां बाधेत ॥

परवचने हि नियमानुपपत्तेरुभयसंज्ञाभावः ।

यस्य पुनः परंकार्यत्वं नियमानुपपत्तेस्तस्योभयोः संज्ञयोर्भावः सिद्धः । कथम् ? । पूर्वा तस्य हेतुसंज्ञा, परा कर्तृसंज्ञा । कथम् ? । एवं स वक्ष्यति—"स्वतन्त्रः प्रयोजको हेतुः" इति । ततः "कर्ता" । कर्तृसंज्ञश्च भवति स्वतन्त्रः । प्रयोजक इति निवृत्तम् । तत्रारम्भसामर्थ्याच्च हेतुसंज्ञा परंकार्यत्वाच्च कर्तृसंज्ञा भविष्यति ॥

(प्रदीपः) हेतुमदिति । हेतुसंज्ञा यस्मिन्सूत्रे विद्यते तद्धेतुमत् तत्र चग्रहणं कर्तव्यम् । समावेशस्य च प्रयोजनं कारयतीति हेतुमण्णिच्कर्तरि लकारः ॥

(उद्योतः) हेतुमतिचेति चग्रहणमिति भ्रमं वारयति—हेतुसंज्ञेति ॥

(असमावेशदूषणबाधकभाष्यम्)

नन्नु च यस्याप्येकसंज्ञाधिकारस्तस्यापि कर्तृसंज्ञापूर्विका हेतुसंज्ञा ॥ कथम् ? । अनुवृत्तिः क्रियते ॥

(असमावेशदूषणसाधकभाष्यम्)

पर्यायः प्रसज्येत । एका संज्ञेति वचनान्नास्ति यौगपद्येन संभवः ॥

(९७६ दूषणान्तरवार्तिकम् ॥ ७ ॥

॥ * ॥ गुरुलघुसंज्ञे नदीघिसंज्ञे ॥ * ॥

(भाष्यम्) गुरुलघुसंज्ञे नदीघिसंज्ञे बाधेयाताम् । गार्गीबन्धुः वात्सीबन्धुः । वैन्नं विविनय्य ॥

परवचने हि नियमानुपपत्तेरुभयसंज्ञाभावः ।

यस्य पुनः परंकार्यत्वं नियमानुपपत्तेस्तस्योभयोः संज्ञयोर्भावः सिद्धः । कथम् ? । पूर्वे तस्य नदीघिसंज्ञे परे गुरुलघुसंज्ञे । तत्रारम्भसामर्थ्याच्च नदीघिसंज्ञे, परंकार्यत्वाच्च गुरुलघुसंज्ञे भविष्यतः ॥

(प्रदीपः) गुरुलघुसंज्ञे इति । यदा घिनदीसंज्ञे वर्णमात्रस्य क्रियेते तदायं दोषः । यदा तु तदन्तस्य तदा भिन्नविषयत्वात्सिद्धः समावेशः । तस्य तु प्रयोजनं वात्सीबन्धुरित्यत्र नदीबन्धुनीति पूर्वपदान्तोदात्तत्वं नदीसंज्ञानिबन्धनं भवति । (वात्सीबन्धो इति) गुरोरनृत इति प्लुतश्च गुरुसंज्ञानिबन्धनः ॥ घिलघुसंज्ञासमावेशस्य च प्रयोजनं विश्च ना च विनराविति घिलक्षणः पूर्वनिपातः । विन्नोर्भावो वैन्नमिति इगन्ताच्च लघुपूर्वादित्यण् । छन्दमनोज्ञादित्वाद्वुञि प्राप्ते तदभावश्चिन्त्यः । विनरावाचष्टे इति णिचि टिलोपे च कृते विविनय्येति ल्यपि लघुपूर्वादित्ययादेशः ॥

(उद्योतः) निबन्धन इति । ननु वात्सीबन्धुरित्यत्र प्लुताप्राप्तेर्भाष्यस्य न्यूनतैवेति चेन्न । प्लुतविधायके दूरादाह्वानं ज्ञापनमात्रोपलक्षणं, न त्वभिमुखीकृत्य ज्ञापनरूपसंबोधनस्य संबोधनविभक्तिनियामकस्योपलक्षणम् । एवं चागच्छतु भवान् गार्गीबन्धुर्वात्सीबन्धुरिति वाक्यवर्तिन उदारहरणत्वमिति भाष्याशयसत्त्वेनादोषात् । अतिप्रसङ्गस्तु व्यवस्थितविभाषयाऽनभिधानेन वा परिहरणीय इत्याहुः ॥ चिन्त्य इति । अत्रेयं चिन्ता—अस्मादेव भाष्यप्रयोगात्तस्यानित्यत्वं तेनोक्तप्रयोगसिद्धिरित्याहुः ॥

(असमावेशदूषणबाधकभाष्यम्)

नन्नु च यस्याप्येकसंज्ञाधिकारस्तस्यापि नदीघिसंज्ञापूर्विके गुरुलघुसंज्ञे ॥ कथम् ? । अनुवृत्तिः क्रियते ॥

(प्रदीपः) नदीघिसंज्ञापूर्विके इति । ननु विशेषविषये नदीघिसंज्ञे गुरुलघुसंज्ञे तु सामान्यविषये ते कथं नदीघिसंज्ञापूर्विके युज्येते । एवं मन्यते—वाक्यभेदेन सम्बन्धः करिष्यते । ह्रस्वमक्षरं लघुसंज्ञं भवति । ततो [घि ।] घिसंज्ञं च लघुसंज्ञमिति । एवं दीर्घं गुरुसंज्ञम् । ततो [नदी ।] नदीसंज्ञं च गुरुसंज्ञमिति ॥

(उद्योतः) ततो घिसंज्ञं चेति । तथा च नदीघिसंज्ञाविषये ते संज्ञे नदीघिसंज्ञापूर्विके इति भाष्यार्थ इति भावः ॥

(असमावेशदूषणसाधकभाष्यम्)

पर्यायः प्रसज्येत । एका संज्ञेति वचनान्नास्ति यौगपद्येन संभवः ॥

(प्रदीपः) पर्याय इति । नदीघिसंज्ञाभ्यां गुरुलघुसंज्ञयोर्नित्ये बाधे प्राप्ते तयोरनुवृत्तिः पर्यायार्थैव स्यादित्यर्थः ॥

(उद्द्योतः) पर्यायार्थैवेति। एवं ह्येका संज्ञेति नियमो न बाधित इति भावः॥ तदन्तस्य घिनदीसंज्ञे इति सिद्धान्तः॥

(९७७ दूषणान्तरवार्तिकम्॥ ८॥)

॥*॥ परस्मैपदसंज्ञा पुरुषसंज्ञा॥*॥

(भाष्यम्) परस्मैपदसंज्ञां पुरुषसंज्ञा बाधेत॥ परवचने हि नियमानुपपत्तेरुभयसंज्ञाभावः॥ यस्य पुनः परंकार्यत्वं नियमानुपपत्तेस्तस्योभयोः संज्ञयोर्भावः सिद्धः। कथम्?। पूर्वा तस्य पुरुषसंज्ञा परा परस्मैपदसंज्ञा। कथम्?। एवं स वक्ष्यति—"तिङस्त्रीणित्रीणि प्रथममध्यमोत्तमा" इत्येवं सर्वं पुरुषनियममनुक्रम्य तस्यान्ते "लः परस्मैपदम्" इति। तत्रारम्भसामर्थ्याच्च पुरुषसंज्ञा परंकार्यत्वाच्च परस्मैपदसंज्ञा भविष्यति॥

(प्रदीपः) परस्मैपदसंज्ञामिति। ततश्च क्रामतीत्यादौ दीर्घत्वं न स्यात् शतर्येव तु स्यात्॥ ननु च सिचिवृद्धिरिति ज्ञापकात्समावेशो भविष्यति। नैतदस्ति। अस्माद्वचनादस्मिन्कार्ये पर्यायः स्यान्न समावेशः। ततश्च पाक्षिकी वृद्धिः स्यात्॥

(उद्द्योतः) ननु चेति। तत्र शत्रादिपरसिचोऽभावात्तिङ् परस्मैपदमेव गृह्यत इति भावः॥

(असमावेशदूषणबाधकभाष्यम्)

ननु च यस्याप्येकसंज्ञाधिकारस्तस्यापि परस्मैपदसंज्ञापूर्विका पुरुषसंज्ञा। कथम्॥ अनुवृत्तिः क्रियते॥

(असमावेशदूषणसाधकभाष्यम्)

पर्यायः प्रसज्येत। एका संज्ञेति वचनान्नास्ति यौगपद्येन संभवः॥

(उद्द्योतः) पर्याय इति। एकसंज्ञाधिकाराबाधायेति भावः। वस्तुत इष्टानुरोधादूर्णोतेर्विभाषाग्रहणाच्च समावेशज्ञापकत्वमेवास्येत्येका संज्ञेति पाठेपि न दोषः।

(असमावेशदूषणबाधकभाष्यम्)

परस्मैपदसंज्ञाप्यनवकाशा वचनाद्भविष्यति॥

(प्रदीपः) परस्मैपदसंज्ञापीति। ततश्च पर्याये लब्धे अनुवृत्तिः समावेशार्था भविष्यतीति भावः।

(असमावेशदूषणसाधकभाष्यम्)

सावकाशा परस्मैपदसंज्ञा॥ कोऽवकाशः?॥ शतृक्वसू अवकाशः॥

(इत्येकासंज्ञेतिन्यासे दूषणानि॥)

(अथ परंकार्यवचने दूषणानि॥)

(९७८ दूषणवार्तिकम्॥ ९॥)

॥*॥ परवचने सिति पदं भम्॥*॥

(भाष्यम्) परवचने सिति पदं भसंज्ञमपि प्राप्नोति। "अयं ते योनिर्ऋत्वियः"। "प्रजां विन्दाम ऋत्वियः"। आरम्भसामर्थ्याच्च पदसंज्ञा, परंकार्यत्वाच्च भसंज्ञा प्राप्नोति॥

(प्रदीपः) ऋत्विय इति। भसंज्ञायां सत्यामोर्गुणः स्यात्॥ पदसंज्ञा त्ववग्रहार्था स्यात्॥

(उद्द्योतः) इदानीं परंकार्यत्वपक्षे दोषानाह—भाष्ये—परवचन इति। ऋत्विये तदस्य प्राप्तमित्यधिकारे ऋतोरणिति वर्तमाने छन्दसि घसिति घस्। पदसंज्ञा त्विति। गुणेऽवादेशे लोपः शाकल्यस्येत्यर्थमपि सेति बोध्यम्॥

(९७९ दूषणान्तरवार्तिकम्॥ १०॥)

॥*॥ गतिबुद्ध्यादीनां ण्यन्तानां कर्म कर्तृसंज्ञम्॥*॥

(भाष्यम्) गतिबुद्ध्यादीनां ण्यन्तानां कर्म कर्तृसंज्ञमपि प्राप्नोति। आरम्भसामर्थ्याच्च कर्मसंज्ञा, परंकार्यत्वाच्च कर्तृसंज्ञा प्राप्नोति॥

(प्रदीपः) गतिबुद्ध्यादीनामिति। एकसंज्ञाधिकारे गत्यादिसूत्रं कर्मसंज्ञायां सिद्धायां नियमार्थम्। तथा हि—प्रयोज्यः स्वव्यापारे स्वतन्त्रः प्रयोजकव्यापारेण चाप्यते इति संज्ञाद्वयप्रसङ्गे एकसंज्ञाधिकारादन्यतरया भाव्यम्। तत्र प्रत्ययार्थस्य प्राधान्यात्तत्प्रयुक्तया कर्मसंज्ञया प्रवर्त्यम्। गुणप्रधानसंनिधौ प्रधानस्य प्रयोजकत्वे संभवति पृथग्गुणास्तद्विरुद्धं स्वकार्यं न प्रयुञ्जते। ततश्च सिद्धायां प्रयोज्यस्य कर्मसंज्ञायां गत्यर्थादीनामेवाण्यन्तानां कर्ता ण्यन्तानां कर्मसंज्ञो भवति नान्येषामिति नियमः क्रियते। तेन पाचयत्योदनं देवदत्तो यज्ञदत्तेनेति कर्मसंज्ञा न भवति। प्रधानप्रयुक्तकर्मसंज्ञाऽभावे च गुणक्रियानिमित्ता कर्तृसंज्ञा प्रवर्तते। यदा तु परं कार्यमिति पाठस्तदाऽविरोधात्सर्वत्र संज्ञाद्वयप्रसङ्गे गत्यर्थादीनामेवेति नियमेन ण्यन्तधात्वन्तरप्रयोज्यात्कर्मसंज्ञा व्यावर्त्यते। गत्यर्थादिप्रयोज्यस्य तु संज्ञाद्वयप्रसङ्ग इत्यर्थः॥

(उद्द्योतः) नियमार्थमिति। यद्यपि परंकार्यत्वपक्षेपि गत्यादिसूत्रं नियमार्थं तथाप्यत्र पक्षे इष्टसिद्धिरिति भावः॥ ननु परत्वात्कर्तृत्वे प्राप्ते कर्मसंज्ञाविध्यर्थमेव गत्यादिसूत्रं स्यात्कथं नियमार्थत्वमित्यत आह—तथाहीति। प्राधान्यादिति। शब्दशास्त्रत्वाच्छाब्दं प्राधान्यमन्तरङ्गत्वादिभ्यो बलवत्। लोकेप्यन्तरङ्गकार्यात्प्रधानकार्यस्य बलवत्त्वं दृष्टं मात्रेराजस्थले इति भावः॥ अविरोधादिति। पूर्वेणापवादेन निवर्तितस्य परकार्यस्य प्रवर्तकेनानेन निरवकाशपूर्वकार्यस्य निवर्तयितुमशक्यत्वैकसंज्ञानियमराहित्येन च विरोधाभावादित्यर्थः॥ गत्यर्थादीनामेवेति। एवं कर्मसंज्ञैवेति नियमस्तु न, प्राकडारादिति शास्त्रबाधापत्तेः॥ आरम्भसामर्थ्याचेति भाष्ये—हेतुमति चेति सूत्रे भाष्ये गतिग्रहणस्य नियमत्वोक्त्या कर्तुरित्यस्य ण्यन्तधातुविषयत्वावश्यकत्वेन ण्यन्तधातुविषयस्य कर्तुरीप्सिततममित्यस्यारम्भसामर्थ्यादित्यर्थः॥ वस्त्वेतन्ना-

ष्यवलाद्गत्यादिसूत्रं विध्यर्थम् । परत्वान्तरङ्गत्वोपजीव्यत्वैः कर्तृत्वप्राप्तेः । एवं च पाचयत्यादौ न दोषः ॥ यत्त्वारम्भसामर्थ्यादित्यस्य गत्यादिसूत्रारम्भसामर्थ्यादित्यर्थ इति ॥ तन्न । प्रधानानुरोधिनः सर्वतो बलवत्त्वात् । किं चात्र पाठे विध्यर्थत्वं दुरुपपादमुभयोरप्यविरोधात्प्राप्तेरिति दिक् ॥

(दूषणनिराकरणभाष्यम्)

नैष दोषः । आचार्यप्रवृत्तिर्ज्ञापयति—न कर्मसंज्ञायां कर्तृसंज्ञा भवतीति । यदयं "हृक्रोरन्यतरस्याम्" इत्यन्यतरस्यांग्रहणं करोति ॥

(प्रदीपः) यदयमिति । यदि तु गत्यर्थादिप्रयोज्यस्य संज्ञाद्वयं प्रावर्त्स्यत्तत्रैव सूत्रे हृक्रावकरिष्येतां नाकरिष्यतान्यतरस्यांग्रहणमित्यर्थः ॥

(उद्योतः) यदीति । ननु समावेशस्य सिद्धत्वेपि पक्षे कर्तृत्वमात्ररूपपर्यायार्थं तदस्तु । न च संज्ञयोः समावेशेपि तत्कार्यविभक्त्योर्यौगपद्यायोगात् कार्यान्तरस्य चाभावात् पर्यायः फलतीति वाच्यम् । समावेशेऽस्य कर्मभिन्नत्वाभावेनोभयप्राप्तावितिनिषेधाप्रवृत्तौ नित्यं षष्ठी । पर्याये तु कर्तृत्वे निषिद्धेपि कर्मत्वे तदभावात् पक्षे भाव्यं षष्ठ्येति विशेषादिति चेन्न । हृक्रविषयेऽनभिधानेन तादृशप्रयोगस्यैवाभाव इति भाष्याशयात् ॥ हृक्राविति । हृकराविल्युचितम् । यद्वा सूत्रगतकृतयणादेशरेफान्तकृशब्दानुकरणोत्तरपदो द्वन्द्वोयं द्विवचनान्त इति बोध्यम् ।

(९८० दूषणान्तरवार्तिकम् ॥ ११ ॥)

॥ * ॥ शेषवचनं च घिसंज्ञानिवृत्त्यर्थम् ॥ * ॥

(भाष्यम्) शेषवचनं च कर्तव्यम्—"शेषो घ्यसखि" । किं प्रयोजनम्? । घिसंज्ञानिवृत्त्यर्थम् । नदीसंज्ञायां घिसंज्ञा मा भूदिति शकट्यै पद्धत्यै बुद्ध्यै धेन्वै । इतरथा हि परंकार्यत्वाच्च घिसंज्ञा आरम्भसामर्थ्याच्च "ङिति ह्रस्वश्च" इति नदीसंज्ञा।

(प्रदीपः) शकट्यै इति । शकटिशब्दान्ङेप्रत्यये कृते परत्वान्नदीसंज्ञानिमित्ते आटि कृते तस्य ङिद्वत्त्वाद्घेर्ङितीति गुणः प्राप्नोति ॥

(९८१ दूषणपरिहारवार्तिकम् ॥ १२ ॥)

॥ * ॥ न वाऽसंभवात् ॥ * ॥

(भाष्यम्) न वा कर्तव्यम् । नदीसंज्ञायां घिसंज्ञा कस्मान्न भवति? । असंभवात् ॥ कोसावसंभवः? ॥

ह्रस्वलक्षणा हि नदीसंज्ञा घिसंज्ञायां च गुणः ॥ ह्रस्वलक्षणा हि नदीसंज्ञा, घिसंज्ञायां च गुणेन भवितव्यम् । तत्र वचनप्रामाण्यान्नदीसंज्ञायां घिसंज्ञाभावः । तत्र वचनप्रामाण्यान्नदीसंज्ञायां घिसंज्ञा न भविष्यति । किं कारणम्? । आश्रयाभावात् ॥

(प्रदीपः) न वा संभवादिति । अयं भावः—यद्यत्र घिसंज्ञा प्रवर्तेत तदान्तरङ्गत्वात् पूर्वमेव तस्याः प्रवृत्तिः स्यात् । नदीसंज्ञा तु ङित्प्रत्ययापेक्षा बहिरङ्गा । तत्र घिलक्षणे गुणे कृते ह्रस्वाभावादल्विधित्वाच्च स्थानिवत्त्वाभावान्नदीसंज्ञा नैव प्रवर्तेतेति नदीसंज्ञाविधानं ह्रस्वस्यानर्थकमेव स्यात् । तस्मान्नदीसंज्ञाविधानसामर्थ्यादत्र घिसंज्ञा न भवतीति ॥

(उद्योतः) ननूपपादितरीत्या संज्ञासमावेशसंभव इत्यत आह—अयं भाव इति ॥ तत्र घिलक्षणे इति । गुणेन नदीत्वनिमित्तविनाशेन युगपत्तयोरसंभवेन नदीसंज्ञापेक्षया परत्वादिति भावः ॥ अल्विधित्वाच्चेति । पूर्वविप्रभावादचः परस्मिन्नित्यस्याप्यभाव इति बोध्यम् ॥ तस्मादिति । इष्टानुरोधादेवमेव कल्प्यते न त्वल्विधावपि स्थानिवत्त्वादीति भावः ॥ भाष्ये—आश्रयाभावादिति । नदीत्वस्याश्रयभूतह्रस्वाभावादित्यर्थः ॥

(९८२ दूषणसाधकवार्तिकम् ॥ १३ ॥)

॥ * ॥ आश्रयाभावान्नदीसंज्ञायां घिसंज्ञानिवृत्तिरिति चेद्यणादेशाभावः ॥ * ॥

(भाष्यम्) आश्रयाभावान्नदीसंज्ञायां घिसंज्ञानिवृत्तिरिति चेदेवमुच्यते यणादेशोऽपि न प्राप्नोति ॥

(दूषणपरिहारभाष्यम्)

नैष दोषः ।

(९८३ दूषणपरिहारसाधकवार्तिकम् ॥ १४ ॥)

॥ * ॥ नद्याश्रयत्वाद्यणादेशस्य ह्रस्वस्य नदीसंज्ञाभावः ॥ * ॥

नद्याश्रयो यणादेशः । यदा नदीसंज्ञया घिसंज्ञा बाधिता तत उत्तरकालं यणादेशेन भवितव्यम् । नद्याश्रयत्वाद्यणादेशस्य ह्रस्वस्य नदीसंज्ञा भविष्यति ॥

(प्रदीपः) नद्याश्रयत्वादिति । यं विधिं प्रत्युपदेशोऽनर्थकः स विधिर्बाध्यते यस्य तु विधेर्निमित्तमेव नासौ बाध्यते इति भावः ॥

(उद्योतः) यस्य त्विति । नदीत्वाभावे घित्वानिवृत्तेर्गुणेन यणो बाधाद् यणो निमित्तं नदीत्वमिति भावः ॥

(९८४ दूषणान्तरवार्तिकम् ॥ १५ ॥)

॥ * ॥ बहुव्रीह्यर्थं तु ॥ * ॥

(भाष्यम्) **बहुव्रीहिप्रतिषेधार्थं तु शेषग्रहणं कर्तव्यम्—"शेषो बहुव्रीहिः" इति ॥**

(उद्द्योतः) मास्तु शेषवचनं घिसंज्ञानिवृत्त्यर्थम्, बहुव्रीहिप्रतिषेधार्थं तु कर्तव्यमेवेत्याह—भाष्ये—**बहुव्रीह्यर्थं त्विति** ॥

(प्रयोजनसाधकभाष्यम्)

किं प्रयोजनम् ? ।

(९८५ प्रयोजनवार्तिकम् ॥ १६ ॥)

॥ * ॥ प्रयोजनमव्ययीभावोपमानद्विगुकृल्लोपेषु ॥ * ॥

(भाष्यम्) **अव्ययीभाव—उन्मत्तगङ्गम् लोहितगङ्गम् । उपमान—शस्त्रीश्यामा कुमुदश्येनी । द्विगु—पञ्चगवं दशगवम् । कृल्लोपे—निष्कौशाम्बिः निर्वाराणसिः ॥**

(प्रदीपः) **उन्मत्तगङ्गमिति** । अत्र बहुव्रीहिसंज्ञायां सत्यां पूर्वपदप्रकृतिस्वरः पाक्षिकश्च कप्समासान्तः प्राप्नोति ॥ **शस्त्रीश्यामेति** । यदा श्यामाशब्दः शस्त्र्यामेव उपमाने वर्तते, उपमेयं तु समासवाच्यं तदाऽन्यपदार्थवृत्तित्वाद्बहुव्रीहिसंज्ञाप्रसङ्गात्तन्निबन्धनः पाक्षिककप्प्रसङ्गः । स्वरस्तु **तत्पुरुषे तुल्यार्थेति** विधीयते इति तत्र नास्ति विशेषः ॥ **पञ्चगवमिति** । यदा समाहारो भावरूपो वाच्यः तदान्यपदार्थसद्भावः । समाह्रियमाणार्थत्वे तु तदभावः । बहुव्रीहिसंज्ञायां सत्यां तन्निबन्धनस्वरप्रसङ्गः । कपस्त्वशेषत्वात्प्रसङ्गाभावः ॥ नन्वत्र टच्श्चित्करणाद्बहुव्रीहिस्वरो न भविष्यति । एवं तर्ह्युदाहरणदिगियम् । इदं त्वत्रोदाहरणं पञ्चपात्रमिति ॥ **निष्कौशाम्बिरिति** । क्रान्तस्यान्यपदार्थस्य समासवाच्यत्वे बहुव्रीहिसंज्ञायां तन्निबन्धनो नदीलक्षणः कप्प्रसङ्गः । यदा तु पूर्वपदमेव क्रान्ताद्यर्थवृत्ति तदान्यपदार्थाभावः ॥

(उद्द्योतः) **अत्रेति** । उन्मत्तेतिक्तान्तस्य पूर्वनिपातस्तु बहुव्रीहित्वाभावेप्युपसर्जनत्वेन तं विना संज्ञाया अप्रतीतेश्चार्थिक इति भावः । नित्यनपुंसकत्वं तु संज्ञयोः समावेशेन सिद्धम् ॥ **पाक्षिकः कबिति** । शेषादिति कपो **न संज्ञायामिति** निषेधाच्चिन्त्यमिदम् । शेषग्रहणे तु नदीपदघटितसमुदायस्यान्यपदार्थे विद्यमानस्य समासोक्तेः शेषत्वाभावान्न बहुव्रीहिरिति बोध्यम् ॥ ननु समानाधिकरणसमासोयम् । अत एव मृगचपलेत्यादौ पुंवत्त्वम् । तत्कान्यपदार्थप्रतीतिरत आह—**यदेति** । अयमपि पक्षस्तत्सूत्रभाष्ये स्पष्टः ॥ **भावरूप इति** । विशेष्यभूत इत्यर्थः ॥ **समाह्रियमाणेति** । **समाहारे चेत्यत्र** कर्मसाधनः समाहारशब्द इति भावः ॥ **अशेषत्वादिति** । **शेषादितिसूत्रे** समासान्तापेक्षया शेष इत्यभिमानेनेदम् । **अनन्तरबहुव्रीह्यधिकारापेक्षं शेषत्वमिति** भाष्यसंमतपक्षे तु तस्यापि प्रसङ्ग इति चिन्त्यम् ॥ **टच्श्चित्करणादिति** । अस्यान्यत्र राजगवीत्यादौ चारितार्थ्यादिदं चिन्त्यमिति कश्चित् ॥ **पञ्चपात्रमिति** । अत्र शेषत्वात्कपोप्यापत्तिः । एतानि प्रयोजनानि शेषग्रहणस्य पदतः शेषार्थकत्वपक्षे । त्रिकतः शेषे त्वन्त्यं द्वयं शेषग्रहणे कृते सिध्यति । आद्यं तु प्रयोजनद्वयं त्रिकतः शेषे शेषग्रहणे कृतेपि न सिध्यतीति बोध्यम् ॥ **समासवाच्यत्वे इति** । समास एव क्रान्ताद्यर्थप्रतीतेः । **यदागमे** हीतिन्यायेनैकार्थीभावबलात्समासस्यैव सोर्थ इति भावः ॥ **यदा त्विति** । एकार्थीभावस्तु पञ्चम्यर्थान्तर्भावेणेति तद्भावः ॥

(९८६ दूषणान्तरवार्तिकम् ॥ १७ ॥)

॥ * ॥ तत्र शेषवचनाद्दोषः संख्यासमानाधिकरणनञ्समासेषु बहुव्रीहिप्रतिषेधः ॥ * ॥

(भाष्यम्) **तत्र शेषवचनाद्दोषो भवति । संख्यासमानाधिकरणनञ्समासेषु बहुव्रीहेः प्रतिषेधः प्राप्नोति ॥ संख्या—द्वीरावतीको देशः, त्रीरावतीको देशः । समानाधिकरण—वीरपुरुषको ग्रामः । नञ्समासे—अब्राह्मणको देशः, अवृषलको देशः ॥**

(प्रदीपः) क्रियमाणेपि शेषग्रहणे दोषान्तरप्रसङ्गमाह—**तत्रेति** । एकसंज्ञावादी तु शेषग्रहणं न करोति । अनवकाशाभिरव्ययीभावादिसंज्ञाभिर्बहुव्रीहिसंज्ञाबाधस्य सिद्धत्वात् । द्वीरावतीकादिषु तु परत्वाद्बहुव्रीहिर्भविष्यति ॥ **द्वीरावतीक इति** । **नदीभिश्चेत्यव्ययीभावः** प्राप्नोति । तस्य त्ववकाशः पञ्चनदमिति यदा समाह्रियमाणोर्थो वाच्यः ॥

(उद्द्योतः) **क्रियमाणेपीति** । तत्करणमेव प्रथमो दोषः । कृते दोषान्तरमपीति भावः । संख्यासमानाधिकरणनञां समासोक्तेः शेषत्वाभावात्तत्र बहुव्रीह्यप्राप्तिरिति बोध्यम् ॥ **शेषग्रहणं न करोतीति** । पदतः शेषार्थे न करोति, त्रिकतः शेषार्थे तु करिष्यतीत्यर्थः ॥ **परत्वादिति** । नञ्समासादयोऽन्यपदार्थाविवक्षायां चरितार्थाः । अव्ययीभावोपि समाह्रियमाणार्थत्वे चरितार्थः । बहुव्रीहिरप्यन्यत्र चरितार्थः । न च समानाधिकरणतत्पुरुषविषये बहुव्रीहिः क्व चरितार्थः ? व्यधिकरणे चरितार्थः इत्यभिमानात् । यद्वा तस्य तद्बाधकत्वमनवकाशत्वेनैव । **परत्वं** च बाधकत्वोपलक्षणम् । भाष्ये **विप्रतिषेधादित्यपि** तथैव बोध्यम् ॥ **प्राप्नोतीति** । तथा चानयोः पदयोर्न शेषत्वमिति बहुव्रीह्यप्राप्तिः ॥ ननु द्वीरावतीकेऽनवकाशत्वान्नदीभिश्चेत्यनेनैव भाव्यम् । एवं च कथमत्र बहुव्रीहिः किमर्थं वा निषेधोऽत आह—**तस्य त्ववकाश इति** ॥ ननु तत्रापि समाहारस्यान्यपदार्थस्य सत्त्वात् कथमवकाशोऽत आह—**यदेति** । एवं सति पञ्चानां नदीनां समाहार

इत्यर्थे परत्वाद्बहुव्रीहिः प्राप्नोति सोपि शेषग्रहणादेव वारणीयः परं-कार्यत्वमिति पाठे इति दिक् । वस्तुतः समाहारे चायमिष्यत इत्युक्तेर्भावसाधनत्वाच्च समाहारशब्दस्य समाहाररूपेऽन्यपदार्थेऽयमपवाद इति मत्वा क्षीरावतीके शेषग्रहणाद्भाष्ये दोष उक्तः । संख्येत्यनुवर्त्तमाने नदीभिश्चेत्यनेनैषां पदानां ग्रहणेनाशेषत्वात् ॥

(९८७ दूषणवार्तिकम् ॥ १८ ॥)

॥ * ॥ कुल्लोपे च शेषवचनात्प्रादिभिर्न बहुव्रीहिः ॥ * ॥

(भाष्यम्) कुल्लोपे च शेषवचनात्प्रादिभिर्बहुव्रीहिर्न प्राप्नोति । प्रपतितपर्णः प्रपर्णकः । प्रपतितपलाशः प्रपलाशक इति ॥

(प्रदीपः) प्रपतितपर्णः प्रपर्णक इति । प्रपर्णक इत्युदाहरणम् । कुल्लोपप्रदर्शनार्थं तु प्रपतितपर्ण इत्युक्तम् । यथा निष्कौशाम्बिरिति तत्पुरुषसंज्ञा भवति । एवं प्रपर्णक इत्यत्रापि स्यादित्यर्थः ॥

(उद्योतः) प्रपतितपर्णे प्रादयो गताद्यर्थ इत्यस्याप्रवृत्तेराह—प्रपर्णक इति ।

(एका संज्ञा इति पाठस्य निर्दोषत्वकथनाधिकरणम्)

(परंकार्यवादिन आक्षेपभाष्यम्)

अथैकसंज्ञाधिकारे कथं सिद्ध्यति ? ।

(९८८ एकसंज्ञावादिनः समाधानवार्तिकम् ॥ १९ ॥)

॥ * ॥ एकसंज्ञाधिकारे विप्रतिषेधाद्बहुव्रीहिः ॥ * ॥

(भाष्यम्) एकसंज्ञाधिकारे विप्रतिषेधाद्बहुव्रीहिर्भविष्यति ।

(९८९ परंकार्यवादिनो बाधकवार्तिकम् ॥ २० ॥)

॥ * ॥ एकसंज्ञाधिकारे विप्रतिषेधाद्बहुव्रीहिरिति चेत् क्वार्थे प्रतिषेधः ॥ * ॥

(भाष्यम्) एकसंज्ञाधिकारे विप्रतिषेधाद्बहुव्रीहिरिति चेत् क्वार्थे प्रतिषेधो वक्तव्यः । निष्कौशाम्बिः । निर्वाराणसिः ।

(उद्योतः) भाष्ये—क्वार्थे प्रतिषेध इत्यस्य क्वार्थे वाच्ये बहुव्रीहिप्रतिषेधो वक्तव्य इत्यर्थः ॥

(एकसंज्ञावादिनः समाधानसाधकभाष्यम्)

तत्पुरुषोऽत्र बाधको भविष्यति ॥

(प्रदीपः) तत्पुरुषोऽत्रेति । परिगणनं मनसि कृत्वाह ॥

(उद्योतः) ननु कुगतीतिसूत्रविहितः समासोपि सुपुरुष इत्यादौ सावकाशोऽत आह—परिगणनमिति । प्रादयो गताद्यर्थ इत्यादीन्यपि परिगणनद्वारा स्वतन्त्रविधायकान्येव न तु तत्प्रपञ्चभूतान्येवेति भावः ॥

(९९० परंकार्यवादिनोबाधकवार्तिकम् ॥ २१ ॥)

॥ * ॥ तत्पुरुष इति चेदन्यत्र क्वार्थात्प्रतिषेधः ॥ * ॥

(भाष्यम्) तत्पुरुष इति चेदन्यत्र क्वार्थात्प्रतिषेधो वक्तव्यः । प्रपतितपर्णः प्रपर्णकः । प्रपतितपलाशः प्रपलाशक इति ॥

(प्रदीपः) इतरो विशेषमप्रतिपद्याह—तत्पुरुष इतीति ॥

(उद्योतः) ननु क्वार्थे विशेष्ये तत्पुरुषः, तद्वति बहुव्रीहिरिति भिन्नविषयत्वात् तत्पुरुष इति चेदित्याद्यनुपपन्नमत आह—इतर इति । प्रादयो गताद्यर्थे इति परिगणनरूपं विशेषमज्ञात्वेत्यर्थः । तथा च तत्र तत्पुरुषप्रतिषेधो वक्तव्य इत्याशयः ॥

(९९१ एकसंज्ञावादिनः समाधानवार्तिकम् ॥ २२ ॥)

॥ * ॥ सिद्धं तु प्रादीनां क्वार्थे तत्पुरुषवचनात् ॥ * ॥

(भाष्यम्) सिद्धमेतत् । कथम् ? प्रादीनां क्वार्थे तत्पुरुषो भवतीति वक्तव्यम् ॥

(प्रदीपः) सिद्धं त्विति । क्वार्थो यत्र समासार्थस्तत्र तत्पुरुषसंज्ञा । प्रपर्णक इत्यत्र तु क्वार्थः पर्णविशेषणं समासार्थस्त्वन्य एवेति बहुव्रीहिर्भवति ॥

(उद्योतः) वस्तुतस्तत्र शेषग्रहणमुभयोरप्यावश्यकं शेषाद्विभाषेति सूत्रे शेषाधिकारः स्यादित्यर्थलाभाय, त्रिकतश्च शेषः तेन परं कार्यमिति पाठे संख्यासमानाधिकरणनञ्समासकुल्लोपेषु दोषैः परिहार्यः । एवं च तद्दोषोक्तिरेकदेश्युक्तिः । उन्मत्तगङ्गमित्यत्र तु दोषः स्थित एवेति परं कार्यमिति पाठो दूषितो भगवता, क्वचित्ते दोषाश्चेति बोध्यम् ॥

(एकसंज्ञाधिकारप्रयोजनाधिकरणम्)

(प्रयोजनानुयोगभाष्यम्)

कानि पुनरस्य योगस्य प्रयोजनानि ? ।

(प्रदीपः) कानि पुनरिति । अस्मिन्प्रकरणे पठितानां संज्ञानां यासां समावेशो नेष्यते ताः प्रयोजनम् । प्रकरणान्तरविहिता अप्यनिष्यमाणसमावेशा उपसंख्यातव्यत्वेन प्रयोजनानि भवन्तीति प्रश्नपूर्वकं दर्शयितुमाह ॥

(उद्योतः) नन्वेतदवधिप्रविष्टसंज्ञासु फलसत्त्वात् प्रश्नानुपपत्तिरत आह—अस्मिन्निति ॥

(९९२ प्रयोजनवार्तिकम् ॥ २३ ॥)

॥ * ॥ प्रयोजनं ह्रस्वसंज्ञां दीर्घप्लुतौ ॥ * ॥

(भाष्यम्) ह्रस्वसंज्ञां दीर्घप्लुतसंज्ञे बाधेते ॥

(प्रदीपः) ह्रस्वसंज्ञामिति । उकालोज् ह्रस्वसंज्ञ इत्युक्तम् । उकारश्चाणुत्वाद्द्विमात्रत्रिमात्रयोर्ग्राहक इति तयोरपि ह्रस्वसंज्ञा प्राप्ता दीर्घप्लुतसंज्ञाभ्यां बाध्यते। स च बाधस्तत्रैव सूत्रे विस्तरेण प्रतिपादितः ॥

(उद्द्योतः) स च बाध इति । तपरत्वसमानार्थकालग्रहणेन प्रतिपादित इति भावः ॥

(९९३ प्रयोजनवार्तिकम् ॥ २४ ॥)

॥ * ॥ तिङ्सार्वधातुकं लिङ्लिटोरार्धधातुकम् ॥ * ॥

(भाष्यम्) तिङ्सार्वधातुकसंज्ञां लिङ्लिटोरार्धकधातुसंज्ञा बाधते ॥

(प्रदीपः) तिङ्सार्वधातुकमिति । लिङ्लिटोश्च सार्वधातुकसंज्ञायां सत्यां तन्निबन्धनाः शबादयः प्राप्नुवन्ति । आर्द्धधातुकसंज्ञा तु तन्निबन्धनेडाद्यर्था । छन्दस्युभयथेति तु तिङामार्द्धधातुकसंज्ञार्थं शेषस्यापि सार्वधातुकसंज्ञार्थं स्यादित्यज्ञापकमसमावेशस्य ॥

(उद्द्योतः) ननु समावेशे छन्दस्युभयथेति व्यर्थं स्यादत आह—छन्दसीति ॥ तिङां, लडाद्यादेशानाम् ॥ शेषस्यापि । तव्यादेः ॥ वस्तुतोऽत्र लङः शाकटायनस्यैवेत्यत एवकारानुवृत्तेर्न समावेशः । एवं लिङाशिषीत्यत्रापि ॥

(९९४ प्रयोजनवार्तिकम् ॥ २५ ॥)

॥ * ॥ अपत्यं वृद्धं युवा ॥ * ॥

(भाष्यम्) अपत्यं वृद्धं युवसंज्ञा बाधते ॥

(प्रदीपः) अपत्यं वृद्धमिति । अत्र समावेशे सति शालङ्केः पैलस्य च यूनश्छात्रा इति विवक्षिते गोत्रेऽलुगचीति फक्फिञोरलुक् प्रसज्येत । फक्फिञोरन्यतरस्यामित्ययं तु लुग्विकल्प आनन्तर्याद्यूनि लुगित्येतमेव लुकं बाधते न तु पैलादिभ्यश्चेत्येतमपि ॥

(उद्द्योतः) भाष्ये वृद्धं, गोत्रम् ॥ अत्र समावेश इति । शलङ्कोर्गोत्रापत्यं बाह्वादीञ् शलङ्कोः शलङ्कादेशश्च । ततो यूनि यञिञोश्चेति फक् । पैलादिभ्यश्चेति लुक् ॥ पीलाशब्दात्पीलाया वेतिगोत्रेऽण् । ततो यून्यणो द्व्यचः इति फिञ् तस्य पूर्वेण लुक् । न च गोत्रेऽलुगचीत्यनेनालुक्यपि यूनि लुगिति परो लुग् भविष्यतीति वाच्यम् । ततोपि परस्य फक्फिञोरन्यतरस्यामित्यस्य प्रवृत्त्या पक्षे प्रत्ययश्रवणप्रसङ्गादिति भावः ॥ सिद्धान्ते तु विकल्पो नेष्यत एवेत्याह—फक्फिञोरिति । अन्तरङ्गत्वात्पैलादिलुकापहारेण सिद्धान्ते यूनि लुगप्राप्तेरिति भावः ॥ गोत्रेऽलुगचीत्यत्र 'भूम्नि प्राप्तस्य लुकोऽलुग्' इति भाष्योक्तेरत्र दोषश्चिन्त्यः ॥ तस्मादौपगवस्य गोत्रस्यापत्यमौपगविरित्यादावेको गोत्र इति नियमादिञ् न स्यादिति फलं बोध्यम् ॥ तुशब्दस्यैवकारार्थत्वादिहासमावेशो बोध्यः ॥

(९९५ प्रयोजनवार्तिकम् ॥ २६ ॥)

॥ * ॥ घिन्नदी ॥ * ॥

(भाष्यम्) घिसंज्ञां नदीसंज्ञा बाधते ॥

(प्रदीपः) घिन्नदीति । शकट्यै इत्यत्र घिलक्षणगुणाभावः ॥

(उद्द्योतः) शकट्यै इति । यद्यपि नदीसंज्ञाविधानसामर्थ्याद् घित्वं नेति प्रागुपपादितं तथापि समावेशस्यानिष्टतामात्रेणोदाहरणत्वमुक्तमिति बोध्यम् ।

(९९६ प्रयोजनवार्तिकम् ॥ २७ ॥)

॥ * ॥ लघु गुरु ॥ * ॥

(भाष्यम्) लघुसंज्ञां गुरुसंज्ञा बाधते ।

(प्रदीपः) लघ्विति । अततक्षदित्यादौ सन्वद्भावाभावः॥

(९९७ प्रयोजनवार्तिकम् ॥ २८ ॥)

॥ * ॥ पदं भम् ॥ * ॥

(भाष्यम्) पदसंज्ञां भसंज्ञा बाधते ।

(९९८ प्रयोजनवार्तिकम् ॥ २९ ॥)

॥ * ॥ अपादानमुत्तराणि ॥ * ॥

(भाष्यम्) अपादानसंज्ञामुत्तराणि कारकाणि बाधन्ते । क ? । धनुषा विध्यति, कंसपात्र्यां भुङ्क्ते, गां दोग्धि, धनुर्विध्यति ॥

धनुषा विध्यतीत्यपाययुक्तत्वाच्च "ध्रुवमपायेऽपादानम्" इत्यपादानसंज्ञा प्राप्नोति "साधकतमं करणम्" इति च करणसंज्ञा। सा परा भवति।

कंसपात्र्यां भुङ्क्ते इत्यत्रापाययुक्तत्वाच्च 'ध्रुवमपायेऽपादानम्' इत्यपादानसंज्ञा प्राप्नोति । 'आधारोधिकरणम्' इति चाधिकरणसंज्ञा । सा परा भवति ।

गां दोग्धीत्यत्रापाययुक्तत्वाच्चापादानसंज्ञा प्राप्नोति 'कर्तुरीप्सिततमं कर्म' इति कर्मसंज्ञा । परा सा भवति ।

धनुर्विध्यतीत्यत्रापाययुक्तत्वाच्चापादानसंज्ञा प्राप्नोति । 'स्वतन्त्रः कर्ता' इति कर्तृसंज्ञा । सा परा भवति ॥

(प्रदीपः) धनुषा विध्यतीति । अपायविवक्षया विना धनुषो व्यधेः साधकतमत्वाभावात् संज्ञाद्वयप्रसङ्गे परत्वात्करणसंज्ञा भवति ।

(उद्द्योतः) नन्वत्र धनुषः करणत्वेनापादानत्वप्रसक्तिरेव नेत्यत आह—अपायेति । धनुर्निर्गतशरकरणकवेधे धनुषः साक्षात्करणत्वासंभवाद् । अवश्यं निर्गमनपूर्वके वेधे विध्यतिं मर्त्ये-

यित्वा तद्धटकनिर्गमनस्यावधिभावेनैव निर्वर्त्तकं धनुर्वेधे परम्परया करणमित्यवश्यं वाच्यमित्यस्त्युभयोः प्राप्तिरिति भावः ॥ कंसपाञ्या-मित्यादेरपि कंसपात्रीतो निर्गतमन्नं भुङ्क्ते इत्यार्थः । ईदृशस्थले धनुः-कंसपात्र्यादेर्द्वैधान्वय इति बोध्यम् ॥ न च कार्यकालपक्षे संज्ञाशा-स्त्राणां विधिप्रदेशेष्वेव वाक्यार्थेन विपरीतं परत्वं पञ्चमीप्रदेशोपस्थि-तापादानसंज्ञायास्तृतीयाविध्युपस्थितकरणसंज्ञायाः परत्वात् । एव-**मल्लोपोऽन** इत्याद्येकवाक्यतापन्नभसंज्ञया नलोपाद्येकवाक्यतापन्न-पदसंज्ञायाः परत्वादसिद्धत्वाच्च बाधो न स्यादिति वाच्यम् । एतद-धिकारस्थसंज्ञाविषये यथोद्देशपक्षस्यैवाङ्गीकारेणादोषात् ॥ भाष्ये—**गांदोग्धीति** । दुहेर्विभागानुकूलव्यापारानुकूलव्यापारार्थकत्वे क-र्तृव्यापारजन्यफलाश्रयत्वात्कर्तुरित्यस्य प्राप्तिः । विभागनिरूपिताव-धित्वविवक्षणाच्चापादानत्वप्राप्तिः । न च पयःसंनिधौ गौर्नेप्सिततमा कारकान्तरापेक्षयैव प्रकर्षस्य विवक्षितत्वात् ॥ ननु स्वकक्षाया-मेव कर्मान्तरापेक्षयापि । अत एवाश्वेन पथा दीपिकया गच्छतीत्य-नेककरणयोगः । **अकथितं** चेत्येतत्त्वपादानत्वाद्यविवक्षायामेवेति न तेन विप्रतिषेध इति दिक् ।

(९९९ प्रयोजनवार्तिकम् ॥ ३० ॥)

॥ * ॥ क्रुधद्रुहोरुपसृष्टयोः कर्म संप्रदानम् ॥ * ॥

(भाष्यम्) क्रुधद्रुहोरुपसृष्टयोः कर्मसंज्ञा संप्र-दानसंज्ञां बाधते ।

(१००० प्रयोजनवार्तिकम् ॥ ३१ ॥)

॥ * ॥ करणं पराणि ॥ * ॥

(भाष्यम्) करणसंज्ञां पराणि कारकाणि बा-धन्ते । क ? । धनुर्विध्यति । असिश्छिनत्तीति ॥

(उद्द्योतः) [धनुर्विध्यतीत्यत्र धनुर्निर्गतशरकरणकवेधो धनु-ष्कर्तृक इति धनुष्करणको धनुर्वृत्तिश्च व्यापार इति वा बोधः । स्वव्यापारे स्वस्यापि करणत्वविवक्षासंभवात् । एवमसिश्छिनत्ती-त्यादौ ।]

(१००१ प्रयोजनवार्तिकम् ॥ ३२ ॥)

॥ * ॥ अधिकरणं कर्म ॥ * ॥

(भाष्यम्) अधिकरणसंज्ञां कर्मसंज्ञा बाधते । क ? । गेहं प्रविशतीति ॥

(उद्द्योतः) भाष्ये—**गेहं प्रविशतीति** । गेहे प्रविशति ग्रामे आगत इत्यादि तु त्वसाध्वेवेति बोध्यम् ॥ केचित्तु यदा तेषां संयोगसमानाधिकरणो व्यापारोऽर्थस्तदा कर्मत्वाप्राप्तेस्तत्साधुत्वं बो-ध्यम् । यदा तु व्यधिकरणो व्यापारोऽर्थस्तदोभयविवक्षायां भाष्यो-दाहरणोपपत्तिर्बोध्येत्याहुः ॥ तद् **हृक्रुभ्यां** चेत्यलुग्विधायकवार्त्ति-कस्यभाष्यविरुद्धं । तत्र हि हृदिस्पृगित्यादौ **द्वितीयार्थे चैषा सप्तमी** द्रष्टव्येत्युक्तम् ॥ गेहं प्रविशतीत्यादौ गेहाधिकरणको गेहकर्मको व्यापार इति बोधः । अत्राधिकरणत्वकर्मत्वयोर्नियतत्वम् ॥

(१००२ प्रयोजनवार्तिकम् ॥ ३३ ॥)

॥ * ॥ अधिकरणं कर्ता ॥ * ॥

(भाष्यम्) अधिकरणसंज्ञां कर्तृसंज्ञा बाधते । क ? । स्थाली पचतीति ॥

(१००३ प्रयोजनवार्तिकम् ॥ ३४ ॥)

॥ * ॥ अध्युपसृष्टं कर्म ॥ * ॥

(भाष्यम्) अध्युपसृष्टं कर्म अधिकरणसंज्ञां बाधते ॥

(१००४ प्रयोजनवार्तिकम् ॥ ३५ ॥)

॥ * ॥ गत्युपसर्गसंज्ञे कर्मप्रवचनीय-संज्ञा ॥ * ॥

(भाष्यम्) गत्युपसर्गसंज्ञे कर्मप्रवचनीयसंज्ञा बाधते ।

(प्रदीपः) गत्युपसर्गसंज्ञे इति । तेन सुसिक्तमि-त्यादौ षत्वं न भवति, सूपमानात् क्त इति गतिसंज्ञकसुश-ब्दाश्रयमन्तोदात्तत्वं च । पूर्वपदप्रकृतिस्वर एव तु भवति ॥

(उद्द्योतः) षत्वं नेति । उपसर्गात्सुनोतीत्यनेनेति शेषः ॥ प्रकृतिस्वरः । तत्पुरुषे तुल्यार्थेत्यनेन ॥

(१००५ प्रयोजनवार्तिकम् ॥ ३६ ॥)

॥ * ॥ परस्मैपदमात्मनेपदम् ॥ * ॥

(भाष्यम्) परस्मैपदसंज्ञामात्मनेपदसंज्ञा बाधते ।

(प्रदीपः) परस्मैपदसंज्ञामिति । तेनाच्योष्टाक्रमत इत्यादौ वृद्धिदीर्घाद्यभावः ॥

(उद्द्योतः) वृद्धिः, सिचि वृद्धिरिति ॥ दीर्घः, क्रमः परस्मैपदेष्विति । क्रमतइति । वृत्तिसर्गेत्यात्मनेपदम् ॥

(१००६ प्रयोजनवार्तिकम् ॥ ३७ ॥)

॥ * ॥ समाससंज्ञाश्च ॥ * ॥

(भाष्यम्) समाससंज्ञाश्च या याः परा अनवका-शाश्च, तास्ताः पूर्वाः सावकाशाश्च बाधन्ते ॥

(प्रदीपः) समाससंज्ञाश्चेति । तेन लोहितगङ्गमित्य-व्ययीभाव एव । द्वीरावतीक इति बहुव्रीहिरेव भवति ॥

(उद्द्योतः) अव्ययीभावोऽनवकाशत्वात् । **बहुव्रीहिः** पर-

त्वात् । समास इति सामान्यसंज्ञां सह सुपेत्यत्र चरितार्थामव्ययीभावादिविशेषसंज्ञा न बाधन्ते, समाससंज्ञानुवादेन तासां विधानात् । अत एव समासान्ता इत्यधिकारेऽव्ययीभावे शरत्प्रभृतिभ्य इत्यादिविधानं संगच्छते ॥

(संज्ञानिवेशक्रमाधिकरणम्)

(१००७ संज्ञावार्तिकम् ॥ ३८ ॥)

॥ * ॥ अर्थवत्प्रातिपदिकम् ॥ * ॥

(भाष्यम्) अर्थवत्प्रातिपदिकसंज्ञं भवति ॥

(१००८ गुणसंज्ञावार्तिकम् ॥ ३९ ॥)

॥ * ॥ गुणवचनं च ॥ * ॥

(भाष्यम्) गुणवचनसंज्ञं च भवत्यर्थवत् ॥

(प्रदीपः) गुणवचनं चेति । एकविषयत्वाच्चकारकरणाच्च गुणवचनप्रातिपदिकसंज्ञयोः समावेशो भवति । उत्तरासु च संज्ञासु प्रातिपदिकमित्यनुवर्तनात्ताभिः प्रातिपदिकसंज्ञा समाविशति । गुणवचनसंज्ञा तु ताभिर्बाध्यते । तस्याश्च ष्यञ्विधिः प्रयोजनम् । ब्राह्मणादिग्रहणं तु समासादिसंज्ञाविषयार्थं प्राणभृज्जात्यादिलक्षणप्रत्ययबाधनार्थं युवाद्यणसमावेशार्थं च ॥

(उद्योतः) एकेति । एवं चोभयोर्निरवकाशत्वान्न बाध्यबाधकभाव इति भावः ॥ नन्वेवमपि पर्यायः स्यादत आह—चकारेति ॥ समाविशतीति । पर्यायस्तु न, अव्ययादाप्सुप इति ज्ञापकात् । संज्ञान्तरविनिर्मुक्तस्थलाभावेनानुवृत्तिं विनैव पर्यायसिद्धिश्चेति भावः ॥ गुणवचनसंज्ञात्विति । एवं चात्र शास्त्रे-गुणवचनशब्देन जातिसंज्ञाव्ययकृदन्ततद्धितान्तसमस्तसर्वनामसंख्याशब्दातिरिक्तः शब्दो गृह्यत इति बोध्यम् । अत एव द्वारवतीत्वमित्यत्र न पुंवद्भाव इति बोध्यम् । अत्र कृत्तद्धितसंज्ञे तदन्तस्य बोध्ये प्रातिपदिकसंज्ञासमानाधिकरणत्वात् । न च गुणिपरशुक्लादीनां गुणवचनत्वानापत्तिस्तत्र मतुब्लोपादिति वाच्यम् । श्रूयमाणतद्धितान्तस्यैव तत्संज्ञाविधानेनादोषात् । गुणगुणिनोरभेदविवक्षायां तथात्वाभावेनाक्षतेश्च । मतुब्लोपस्तु भेदविवक्षायां शुक्लानित्यादेरसाधुत्वाय । तदा मतुपोऽनभिधानमाश्रित्य तु प्रत्याख्यानमिति बोध्यम् । रूपादयो जातिशब्दा असर्वलिङ्गत्वात् ॥ ष्यञ्विधिरिति । 'वोतो गुणवचनात्' 'त्वतलोर्गुणवचनस्येत्यादेरप्युपलक्षणमेतत् ॥ ननु प्रातिपदिकमात्रस्य गुणवचनसंज्ञकत्वे ब्राह्मणादिग्रहणं व्यर्थमत आह—ब्राह्मणादीति । अन्यथा ब्राह्मणगणपत्यादिभ्यः ष्यञ् न स्यात् प्राणभृज्जातिलक्षणो ब्राह्मणशब्दे । वयोवचनलक्षणो बालशब्दे । निपुणादयो युवादयः ॥

(१००९ समासादिसंज्ञावार्तिकम् ॥ ४० ॥

॥ * ॥ समासकृत्तद्धिताव्ययसर्वनामासर्वलिङ्गा जातिः ॥ * ॥

(भाष्यम्) समास—समाससंज्ञा वक्तव्या ॥ कृत्—कृत्संज्ञा च वक्तव्या ॥ तद्धित—तद्धितसंज्ञा च वक्तव्या ॥ अव्यय—अव्ययसंज्ञा च वक्तव्या ॥ सर्वनाम—सर्वनामसंज्ञा च वक्तव्या ॥ असर्वलिङ्गा जातिरिति । एतच्च वक्तव्यम् ॥

(प्रदीपः) असर्वलिङ्गा जातिरिति । लिङ्गानां च न सर्वभागिति लक्षणलक्षितां जातिमाश्रयति । चित्रगुत्वं कारकत्वमौपगवत्वमुच्चैस्त्वं सर्वत्वं गोत्वं बहुत्वं पञ्चत्वं डित्थत्वमिति गुणवचनसंज्ञायाः समासादिसंज्ञाभिर्बाधनात्ष्यञ्न भवति। ऐक्यं राजपौरुष्यमित्यादौ तु ब्राह्मणादित्वात्ष्यञ् ॥ १ ॥

(उद्योतः) आश्रयतीति । न लोकप्रसिद्धामित्यर्थः ॥ एकशब्दे संख्यासंज्ञया राजपुरुषे समाससंज्ञया बाधमाशङ्क्याह—ऐक्यमिति ॥ राजपौरुष्यमिति । अनुशतिकादित्वादुभयपदवृद्धिः ॥

(१०१० संख्यासंज्ञावार्तिकम् ॥ ४१ ॥)

॥ * ॥ संख्या ॥ * ॥

(भाष्यम्) संख्यासंज्ञा च वक्तव्या ।

(१०११ षट्संज्ञावार्तिकम् ॥ ४२ ॥)

॥ * ॥ डु च ॥ * ॥

(भाष्यम्) डुसंज्ञा च वक्तव्या ॥ का पुनर्डुसंज्ञा? ॥ षट् संज्ञा ॥

(१०१२ संज्ञासंज्ञावार्तिकम् ॥ ४३ ॥)

॥ * ॥ एकद्रव्योपनिवेशिनी संज्ञा ॥ * ॥

(भाष्यम्) एकद्रव्योपनिवेशिनी संज्ञा इत्येतच्च वक्तव्यम् ॥

(आक्षेपभाष्यम्)

किमर्थमिदमुच्यते । यथान्यास एव भूयिष्ठाः संज्ञाः क्रियन्ते ? ॥

(उद्योतः) भाष्ये—किमर्थमिति । गुणवचनं चेत्यारभ्यैकद्रव्योपनिवेशिनी संज्ञेत्यन्तं वचनजातं किमर्थमित्यर्थः ॥ वैयर्थ्यमेवोपपादयति—यथा न्यास एवेति ॥

(समाधानभाष्यम्)

सन्ति चैवात्र काश्चिदपूर्वाः संज्ञाः ॥ अपि चैतेनानुपूर्व्येण संनिविष्टानां बाधनं यथा स्यात् ॥ गुणवचनसंज्ञायाश्चैताभिः संज्ञाभिर्बाधनं यथा स्यादिति ॥ आकडारात् ॥ १ ॥

(उद्योतः) समाधत्ते—सन्तिचैवात्रेति । अपूर्वा इति । कृत्संज्ञा तद्धितसंज्ञा असर्वलिङ्गा जातिरित्येकद्रव्योपनिवेशिनीत्येताः तदर्थमेतद्वचनजातमित्यर्थः ॥ समाधन्तरमाह—अपि चेति । संनिविष्टानामिति निर्धारणषष्ठी । तत्र संज्ञासंज्ञया जातिसंज्ञाया बाधाड्डित्थेत्यादौ टाबेव । तथा तया सर्वनामसंज्ञाया बाधात्सर्वायेत्यादौ न स्मै । एवं संज्ञासंज्ञया सर्वप्राचीनसंज्ञाबाध इत्यापूह्यम् ॥ पुनः समाधन्तरमाह—गुणवचनसंज्ञायाश्चेति ।

एवं चैतदतिरिक्तशब्दत्वं शास्त्रे गुणवचनशब्दत्वमित्यर्थादुक्तमिति दिक् ॥ १ ॥

(१६५ विप्रतिषेध(नियम) सूत्रम् ॥ १।४। १ आ० २ सू०)

२४२ विप्रतिषेधे परं कार्यम् ॥ १।४।२ ॥

(विप्रतिषेधशब्दार्थावगमाधिकरणम्)

(आक्षेपभाष्यम्)

विप्रतिषेध इति कोयं शब्दः ? ।

(प्रदीपः) **विप्रतिषेधे ॥ २ ॥** आचार्यवचनानां सर्वेषां प्रामाण्याभ्युपगमाल्लौकिकार्थस्य विरोधवाचिनो विप्रतिषेधशब्दस्येह ग्रहणं न संभवतीति मत्वा पृच्छति—**विप्रतिषेध इति कोयं शब्द इति ॥**

(उद्द्योतः) **विप्रतिषेधे ॥ २ ॥** शब्दस्वरूपे संदेहाभावादर्थस्य विरोधस्य प्रसिद्धत्वात्कोयमिति प्रश्नानुपपत्तिरत आह—**आचार्येति ।** विरोधार्थकत्वे परस्परव्याघातादुभयोर्विरुद्धयोः शास्त्रयोरप्रामाण्यं स्यादित्यर्थः ॥ **सर्वेषामिति ।** अनेन शास्त्रेण पराभ्यनुज्ञानात्तस्य प्रामाण्येप्यन्यस्याप्रामाण्येन सर्वेषां तत्त्वं भग्नमिति भावः ॥

(समाधानभाष्यम्)

विप्रतिपूर्वात्सिधेः कर्मव्यतिहारे घञ् । इतरेतरप्रतिषेधो विप्रतिषेधः । अन्योन्यप्रतिषेधो विप्रतिषेधः ॥

(प्रदीपः) इतरस्तु लौकिकार्थवृत्तिरेवोपात्तो न ह्यस्यात्रान्योर्थः परिभाषित इति मत्वाह—**विप्रतिपूर्वादिति । कर्मव्यतिहार इति** सिधेर्विशेषणम् । व्यतिहारविशिष्टक्रियावचनात्सेधतेर्भावे घञित्यर्थः ॥ **इतरेतरप्रतिषेधोन्योन्यप्रतिषेधइति ।** स एवार्थः पर्यायाभ्यां प्रदर्श्यते । यद्वा पर्यायाप्रतिपत्ती शब्दद्वयेन प्रदर्श्येते ॥

(उद्द्योतः) **इतर इति ।** अप्रामाण्यं त्वग्रे परिहरिष्यत इति भावः ॥ कर्मव्यतिहारे घञो विधानाभावादाह—**सिधेरिति ॥ सेधतेरिति ।** परस्परं प्रतिकूलं गमनमित्यर्थबोधने तस्यैव समर्थत्वादिति भावः ॥ पौनरुक्त्यं परिहरति—**स एवार्थ इति ।** कस्यचित्कश्चित्प्रसिद्ध इति पर्यायोपादानमिति भावः ॥ अस्यागतिकगतित्वेनाह—**यद्वेति ।** प्रतिषेधशब्द एकत्र पाक्षिकप्रतिषेधपरः परत्रात्यन्तिकप्रतिषेधपर इति भावः । एवं च **सकृद्गतिपुनःप्रसङ्ग**पक्षयोः सिद्धये पर्यायाप्रतिपत्तिफलस्य कादाचित्कप्रवृत्तिप्रतिबन्धस्य सर्वथा तत्प्रतिबन्धस्य च प्रतिषेधशब्दार्थत्वेन लोकसिद्धविरोधार्थकतैव फलितेति ध्येयम् ॥

(आक्षेपभाष्यम्)

कः पुनर्विप्रतिषेधः ? ॥

(प्रदीपः) विरोधं पूर्वोक्तेन न्यायेनासंभावयन्पुनः पृच्छति—**कः पुनरिति ॥**

(उद्द्योतः) **पूर्वोक्तेन ।** अप्रामाण्यापत्तिरूपेण ।

(१०१३ समाधानवार्तिकम् ॥ १ ॥)

॥ * ॥ द्वौ प्रसङ्गावन्यार्थावेकस्मिन्स विप्रतिषेधः ॥ * ॥

(भाष्यम्) **द्वौ प्रसङ्गौ यदान्यार्थौ भवत एकस्मिंश्च युगपत्प्राप्नुतः स विप्रतिषेधः ॥**

क पुनरन्यार्थौ क चैकस्मिन्युगपत्प्राप्नुतः ? ।

वृक्षाभ्यां वृक्षेष्वित्यन्यार्थौ, वृक्षेभ्य इत्यत्र युगपत्प्राप्नुतः ॥

(प्रदीपः) **द्वौ प्रसङ्गाविति ।** सर्वस्याचार्यवचनस्य प्रामाण्येपि लब्धावकाशयोर्वचनयोरेकस्मिन्विषये विरुद्धकार्यद्वयसमर्पणादस्त्येव विरोधः । प्रसज्येते इति प्रसङ्गौ विधी ॥ **अन्यार्थाविति ।** अन्यत्र सावकाशौ ॥ **सविप्रतिषेध इति ।** युगपद्यासौ प्राप्तिः सा विरोधनिमित्तत्वादभेदोपचाराद्विप्रतिषेधशब्देनोक्ता ॥

(उद्द्योतः) ननु प्राप्नुत इति क्रिया न सशब्देन परामर्शयोग्या, सर्वनामपरामर्शायोग्यत्वस्यैव तस्यामसत्त्वस्य **वतिसूत्रे** कैयटेन वक्ष्यमाणत्वात् । कर्तृपरामर्शस्तु न, तस्य गुणत्वाद्, द्विवचनापत्तेश्चात आह—**युगपदिति ।** आख्यातोपात्तक्रियायाः परामर्शाभावेप्यध्याहृतप्राप्त्यादिपदोपात्तायाः परामर्शे न दोषः । लिङ्गं तु प्रतिनिर्देशाभिप्रायेणेति बोध्यम् ॥ ननु सा न विप्रतिषेधोऽत आह—**विरोधनिमित्तत्वादिति ।** विरोधफलबाधनिमित्तत्वादित्यर्थः ॥

(आक्षेपभाष्यम्)

किं च स्यात् ? ।

(प्रदीपः) **किं च स्यादिति ।** यदीदं नारभ्येतेति भावः ॥

(उद्द्योतः) नन्वनेन परस्य प्रतिपादनात्कथमयं प्रश्नोऽत आह—**यदीदमिति ॥**

(१०१४ समाधानवार्तिकम् ॥ २ ॥)

॥ * ॥ एकस्मिन्युगपदसंभवात्पूर्वपरप्राप्तेरुभयप्रसङ्गः ॥ * ॥

(भाष्यम्) **एकस्मिन्युगपदसंभवात् पूर्वस्याश्च परस्याश्च प्राप्तेरुभयप्रसङ्गः ॥**

(प्रदीपः) इतरो व्यक्तिपदाऽर्थाश्रयेण पर्यायप्रसङ्गमाह—**एकस्मिन्निति ॥**

(उद्द्योतः) तदनारम्भेऽन्यत्र सावकाशयोः सामर्थ्याभावेन कथं पर्यायप्राप्तिरत आह—**इतरो व्यक्तीति । पर्यायेति ।** एवं

च पाक्षिकबाधो विरोधफलमिति भावः ॥ भाष्ये—**एकस्मिन्नि**त्यस्य लक्ष्ये इति शेषः ॥ **असंभवा**दित्यस्य कार्ययोरिति शेषः ॥ **पूर्वपरप्राप्तेरि**ति ।—पूर्वस्य परस्य च योगस्य प्राप्तेरित्यर्थः । वचनद्वयप्रामाण्यादिति यावत् ॥ भगवता तु धर्मधर्मिणोरभेदमाश्रित्य प्राप्तिशब्देन पूर्वपरशब्दयोः सामानाधिकरण्यमाश्रितम् ॥ **उभयप्रसङ्ग** इति । पर्यायेणेति शेषः ॥

(आक्षेपभाष्यम्)

इदं विप्रतिषिद्धं यदुच्यते *एकस्मिन्युगपदसंभवात्पूर्वपरप्राप्तेरुभयप्रसङ्गः* इति, कथं ह्येकस्मिंश्च युगपदसंभवः स्यात् पूर्वस्याश्च परस्याश्च प्राप्तेरुभयप्रसङ्गश्च स्यात्?॥

(उद्द्योतः) सूत्रयोरेवासंभवप्राप्ती उक्ते इति मत्वा पृच्छति—**इदं विप्रतिषिद्धमि**ति ॥

(समाधानभाष्यम्)

नैतद्विप्रतिषिद्धम् । यदुच्यते 'एकस्मिन्युगपदसंभवात्' इति । कार्ययोर्युगपदसंभवः, शास्त्रयोरुभयप्रसङ्गः ॥

(उद्द्योतः) शास्त्रयोरुभयप्रसङ्ग इति । पर्यायेण शास्त्रयोः प्राप्तेरुभयप्रसङ्ग इत्यर्थः ॥

(१०१५ समाधानसाधकवार्तिकम् ॥ ३ ॥)

॥ * ॥ तृजादिभिस्तुल्यम् ॥ * ॥

(भाष्यम्) **तृजादिभिस्तुल्यं पर्यायः प्राप्नोति । तद्यथा तृजादयः पर्यायेण भवन्ति ॥**

(उद्द्योतः) ननु शास्त्रप्रसङ्गोपि कार्यार्थं एवेति कार्ययोर्युगपदसंभवे कथं शास्त्रयोः प्रसङ्गोऽत आह—**तृजादिभिरि**ति । एवं च युगपदसंभवः पर्यायेणोभयप्रसङ्ग इति तात्पर्यम् ॥

(आक्षेपभाष्यम्)

किं पुनः कारणं तृजादयः पर्यायेण भवन्ति?॥

(१०१६ समाधानवार्तिकम् ॥ ४ ॥)

॥ * ॥ अनवयवप्रसङ्गात्प्रतिपदं विधेश्च ॥ * ॥

(भाष्यम्) **अनवयवेन प्रसज्यन्ते प्रतिपदं च विधीयन्ते ॥**

(प्रदीपः) **अनवयवप्रसङ्गादि**ति । सर्वव्यक्त्युद्देशेन शास्त्रस्य प्रवर्तनादित्यर्थः ॥ **प्रतिपदं विधेश्चे**ति । अनेनोत्सर्गापवादवैधर्म्यं दर्शयति । नह्युत्सर्गः प्रतिपदं विधीयते । तत्र पर्यायप्रसङ्गे नियमार्थमिदं परमेव भवति न पूर्वमिति । एतत्सूत्रारम्भाच्च पूर्वस्य लक्षणस्य तत्रानारम्भोऽनुमीयते । **तदुच्यते सकृद्गतौ विप्रतिषेधे यद्बाधितं तद्बाधितमेवेति ।**

(उद्द्योतः) **सर्वव्यक्त्युद्देशेने**ति । ण्वुल्तृजर्चां धातुमात्राद्विधानन विनिगमकाभावादिति भावः ॥ नन्वनवयवेन प्रसक्तस्यापि सामान्यशास्त्रस्य विशेषेणात्यन्तिकबाधदर्शनादिदमप्रयोजकमत आह—**अनेने**ति । **प्रतिपदं विधेश्चे**त्यस्य बाधकाभावादिति शेषः । उत्सर्गस्य सामान्यविषयत्वमपवादस्य विशेषविषयत्वमिति तद्व्यक्तिविषयकविशेषशास्त्रेण सामान्यशास्त्रस्य तद्विषयकत्वं बाध्यते, तृजादौ तु नैवमित्युभयोरपि प्रतिव्यक्ति प्रवृत्तिः। एवं प्रकृतेऽपि दीर्घत्वशास्त्रयोः कस्यापि व्यक्तिविशेषविषयकत्वाभावेनोभयोरपि स्वस्वविषयसर्वव्यक्तिविषयतयोपप्लवेन पर्यायप्रसङ्ग इति भावः॥ नन्वेवं तद्विषयकपूर्वलक्षणस्याप्रमाणत्वं स्यादत आह—**एतत्सूत्रे**ति । एतच्छास्त्रबलेन पूर्वस्य तद्व्यतिरिक्तव्यक्तिविषयतैव कल्प्यत इति भावः ॥

(१०१७ पक्षान्तरवार्तिकम् ॥ ५ ॥)

॥ * ॥ अप्रतिपत्तिर्वोभयोस्तुल्यबलत्वात् ॥ * ॥

(भाष्यम्) **अप्रतिपत्तिर्वा पुनरुभयोः शास्त्रयोः स्यात् । किं कारणम्? । तुल्यबलत्वात् । तुल्यबले ह्युभे शास्त्रे । तद्यथा—द्वयोस्तुल्यबलयोरेकः प्रैष्यो भवति स तयोः पर्यायेण कार्यं करोति । यदा तु तमुभौ युगपत्प्रेषयतो नानादिक्षु च कार्ये भवतस्तदा यद्यसावविरोधार्थी भवति उभयोर्न करोति॥ किं पुनः कारणमुभयोर्न करोति? । यौगपद्यासंभवात् । नास्ति यौगपद्येन संभवः । तत्र प्रतिपत्त्यर्थं वचनम् । तत्र प्रतिपत्त्यर्थमिदं वक्तव्यम् ॥**

(प्रदीपः) इदानीं जातिपक्षाश्रयेणाह—**अप्रतिपत्तिर्वे**ति । अत्र पक्षे विध्यर्थमिदम्—**परं** भवतीति । तस्मिन् कृते यदि पूर्वस्य प्राप्तिनिमित्तमस्ति ततस्तदपि प्रवर्तते । तदुच्यते—**पुनः प्रसङ्गविज्ञानात्सिद्ध**मिति ।

(उद्द्योतः) ननु तुल्यबलत्वेनैव पर्याय उपपादितस्तत्कथं तेनैवाप्रतिपत्तिरापाद्यतेऽत आह—**इदानीमि**ति । जातिपक्षे तज्जातेरेवोद्देश्यत्वेन तज्जात्युपरक्तव्यक्तौ क्वचित्कार्यान्वयेपि शास्त्रस्य चारितार्थ्यमिति भावः ॥ **ततस्तदपी**ति । अप्रवृत्तौ मानाभावादिति भावः । वृक्षेभ्य इत्यादावेत्वे निमित्ताभावाद्दीर्घस्याप्रवृत्तिरित्यन्यत् ॥ भाष्ये—**तद्यथे**ति । तत्र यथैकः प्रेष्य उभयोर्न करोति, तथा प्रकृते उदाहरणरूपा व्यक्तिरुभयोरपि कार्यं नाश्रयिष्यतीत्यर्थः । वचने त्वन्यत्र चरितार्थे । यथा तत्र प्रेष्यौ परस्पराविरुद्धकार्यकरणेन चरितार्थस्वामिनाविति भावः ॥ **प्रतिपत्त्यर्थमि**त्यस्य विध्यर्थमित्यर्थः ॥

(१०१८ आक्षेपवार्तिकम् ॥ ६ ॥)

॥ * ॥ तव्यदादीनां त्वप्रसिद्धिः ॥ * ॥

(भाष्यम्) **तव्यदादीनां तु कार्यस्याप्रसिद्धिः ।**

नहि किंचित्तव्यदादिषु नियमकारि शास्त्रमारभ्यते येन तव्यदादयः स्युः । यश्च भवता हेतुर्व्यपदिष्टः *अप्रतिपत्तिर्वोभयोस्तुल्यबलत्वात्* इति, तुल्यः स तव्यदादिषु ॥

(प्रदीपः) **तव्यदादीनां तु कार्यस्येति** । परत्वादेः साधुत्वस्य वेत्यर्थः । एकवाक्योपात्तत्वादनवकाशत्वाच्च नास्त्येषां परत्वेन व्यवस्था ॥

(उद्द्योतः) ननु तव्यदादीन्येव कार्याणि किं तेषामपि कार्यं नामेत्यत आह—**परत्वेति** ॥ **एकवाक्येति** । शास्त्रगतमेव पौर्वापर्यं गृह्यत इति भावः ॥ कार्यगतपौर्वापर्याश्रयणे प्याह—**अनवकाशत्वाच्चेति** । धातुत्वजात्याक्रान्तव्यक्तौ क प्रवर्तते क नेत्यत्र विनिगमकाभावादिति भावः ॥

(आक्षेपनिराकरणभाष्यम्)

(भाष्यम्) **नैष दोषः । अनवकाशास्तव्यदादयः । उच्यन्ते च । ते वचनाद्भविष्यन्ति । यश्च भवता हेतुर्व्यपदिष्टः–तृजादिभिस्तुल्यं पर्यायः प्राप्नोतीति, तुल्यः स तव्यदादिषु । एतावदिह सूत्रम् 'विप्रतिषेधे परम्' इति । पठिष्यति ह्याचार्यः "सकृद्गतौ विप्रतिषेधे यद्बाधितं तद्बाधितमेव" इति । पुनश्च पठिष्यति—"पुनः प्रसङ्गविज्ञानात्सिद्धम्" इति ॥**

(प्रदीपः) **तृजादिभिरिति** । आदिशब्दस्य प्रकारार्थत्वात्तृजादिभ्यस्तव्यदादयो न भिन्ना इत्यर्थः ॥

(उद्द्योतः) ननु तव्यदादीत्यादिपदेन तृजादीनामपि ग्रहणात् कथं सादृश्यमत आह—**आदीति** ॥ ननु पर्यायेणोत्पत्तिरेव प्रकारस्तस्य तृजादावपि सत्त्वेन कथं भेदोऽत आह—**तृजादीति** ॥ भाष्ये **आचार्यो**, वार्तिककारः ॥

(आक्षेपभाष्यम्)

किं पुनरियता सूत्रेणोभयं लभ्यम् ? ॥

(समाधानभाष्यम्)

लभ्यमित्याह ॥ कथम् ? । इह भवता द्वौ हेतू व्यपदिष्टौ—तृजादिभिस्तुल्यं पर्यायः प्राप्नोतीति च, 'अप्रतिपत्तिर्वोभयोस्तुल्यबलत्वादिति च । तद्यदा तावदेष हेतुस्तृजादिभिस्तुल्यं पर्यायः प्राप्नोतीति तदा 'विप्रतिषेधे परम्' इत्यनेन किं क्रियते? । नियमः—विप्रतिषेधे परमेव भवतीति । तदैतदुपपन्नं भवति—'सकृद्गतौ विप्रतिषेधे यद्बाधितं तद्बाधितमेव' इति ॥ यदा त्वेष हेतुरप्रतिपत्तिरुभयोस्तुल्यबलत्वात्' इति, तदा "विप्रतिषेधे परम्" इत्यनेन किं क्रियते ? । द्वारम्—विप्रतिषेधे परं तावद्भवति तस्मिन्कृते यदि पूर्वमपि प्राप्नोति तदपि भवति । तदैतदुपपन्नं भवति—'पुनःप्रसङ्गविज्ञानात्सिद्धमिति' ॥

(प्रदीपः) **सकृद्गताविति** । यथा कुरुतात् त्वमिति हेर्लुक् च प्राप्नोति तातङ् चेति परत्वात्तातङ् तस्य स्थानिवद्भावाल्लुङ् न प्रवर्तते ॥ **द्वारमिति** । अप्रतिपत्त्यपनयनेन परशास्त्रप्रवृत्तेर्द्वारमुपायः क्रियत इति यावत् ॥ **पुनःप्रसङ्गविज्ञानादिति** । ईजतुरिति परत्वात्सम्प्रसारणे कृते द्विर्वचनं भवति । लक्ष्यानुरोधेन च व्यक्त्याकृतिपदार्थाश्रयणादनयोः परिभाषयोर्विषयविभागोऽवसेयः ॥

(उद्द्योतः) **यथेति** । न च लुक् कृताकृतप्रसङ्गित्वेन नित्यः, शब्दान्तरप्राप्त्या तस्याप्यनित्यत्वात् । न **चान्तरङ्गानपीति** न्यायात्कैमुतिकन्यायेन परादपि लुको बलवत्त्वेनेदमयुक्तमिति वाच्यम् । परिभाषाणामिष्टसिद्धिमात्रफलकत्वात् ॥ **ईजतुरिति** । न च पूर्वं द्वित्वप्रवृत्तावपि **वचिस्वपीतिलिट्यभ्यासस्येति**संप्रसारणाभ्यामिष्टं सिध्यतीति वाच्यम् । **न संप्रसारणे** इतिनिषेधेनाभ्यासस्य संप्रसारणानापत्तेः ॥ **व्यक्त्याकृतीति** । केचित्तु नहि 'व्यक्तिपक्षे सर्वं शास्त्रं व्याप्नोति न तु जातिपक्षे' इत्यत्र मानमस्ति । पक्षद्वयेपि सर्वव्याप्तिरेकशेषसूत्रे भाष्ये स्पष्टमुक्ता । **न ब्राह्मणं हन्यादित्यादौ** सर्वब्राह्मणहनननिषेधाय जातिपक्षाश्रयणमिति च तत्र स्पष्टम् । किं च भाष्यं पक्षद्वयसाधारणेन दृष्टान्तभेदेन पर्यायाप्रतिपत्ती ये प्राप्ते तदाश्रयेण तद्वचनोपपत्तिपरं न तु जातिव्यक्त्याश्रयेणेति स्पष्टमेव । अन्यथा जातिपक्षप्रवृत्तामप्रतिपत्तिमुपक्रम्य तव्यादिषु दोषाशङ्कापरं भाष्यमसंगतं स्यात् । अनवकाशत्वेनैषां न परत्वेन व्यवस्थेति त्वदुक्त्यसंगततापत्तेश्च अग्रे तृजादितुल्यताया एव तेषु प्रतिपादनाच्च । नहि तृजादयो व्यक्तिपक्षे एव सर्वविषयाः, अपि तु जातिपक्षेपि । किं च व्यक्तिपक्षेप्यन्यव्यक्तिविषयलाभेन चरितार्थस्येयं व्यक्तिर्विरोधात्स्वविषयकत्वं न कल्पयतीत्युपपत्तिरस्ति । किं च जातिपक्षे तज्जात्याश्रयतद्व्यक्तिविषयकत्वमेव नैतद्विषयकत्वमित्यत्र विनिगमकाभावः । तत्रैकः शास्त्रदृष्टान्तोऽपरो लौकिकस्तयोराश्रयणे लक्ष्यानुसारो बीजमित्येव वक्तुमुचितम् । अन्यथा तव व्यक्तिपदार्थाश्रयेण संमते सकृद्गतिन्याये कुरुतात्त्वमित्युदाहरणं त्वदुक्तमसंगतं स्यात् । कुरुशब्दाद्धेर्लुगिति वचनस्य तातङ्भावपक्षे चारितार्थ्येन कुरुशब्दाद्धेस्तातङिति वचनस्यानवकाशत्वेन विप्रतिषेधाप्रसक्तेरिति वदन्ति ॥

(पूर्वविप्रतिषेधाङ्गीकाराधिकरणम्)

(१०१९ न्यासान्तरवार्तिकम् ॥ ७ ॥)

[॥ * ॥ विप्रतिषेधे परमङ्गाधिकारे पूर्वम् ॥ * ॥]

विप्रतिषेधे परमित्युक्त्वाऽङ्गाधिकारे पूर्वमिति वक्तव्यम् । किं कृतं भवति ? । पूर्वविप्रतिषेधा न पठितव्या भवन्ति —*गुणवृद्ध्यौत्वतृज्वद्भावेभ्यो

नुम् पूर्वविप्रतिषिद्धम् * *नुमचिरतृज्वद्भावेभ्यो नुट्* इति ॥

(उद्द्योतः) अङ्गाधिकारस्थवक्ष्यमाणपूर्वविप्रतिषेधवार्त्तिकाश्रयणे गौरवं मत्वाह—**विप्रतिषेधे इति** । पूर्वं विप्रतिषिद्धमिति कर्मधारयः । नुम्शब्दरूपस्य विशेष्यत्वान्नपुंसकनिर्देशः ॥

(आक्षेपभाष्यम्)

कथं ये परविप्रतिषेधाः—*इत्वोत्वाभ्यां गुणवृद्धी भवतो विप्रतिषेधने* इति । सूत्रं च भिद्यते ॥

(उद्द्योतः) अङ्गाधिकारे परविप्रतिषेधस्यापीष्टत्वेनेदमसंगतं मत्वाह अन्यः—**कथमिति** ॥ **सूत्रं च भिद्यत इति** । अधिकसन्नकरणादिति भावः । चेनानङ्गाधिकारस्थपूर्वविप्रतिषेधासंग्रहरूपदोषसंग्रहः । सूत्रं भिद्यते चेत्यलम् ॥

(सिद्धान्तिसमाधानभाष्यम्)

यथान्यासमेवास्तु ॥

कथं ये पूर्वविप्रतिषेधाः ?॥

'विप्रतिषेधे परम्' इत्येव सिद्धम् । कथम् ? । परशब्दोयं बह्वर्थः । अस्त्येव व्यवस्थायां वर्तते तद्यथा—'पूर्वः परः' इति । अस्त्यन्यार्थे वर्तते—'परपुत्रः परभार्या' अन्यपुत्रोऽन्यभार्येति गम्यते । अस्ति प्राधान्ये वर्तते तद्यथा—'परमियं ब्राह्मण्यस्मिन्कुटुम्बे' प्रधानमिति गम्यते । अस्तीष्टवाची परशब्दः तद्यथा—'परं धाम गतः' इष्टं धाम गत इति गम्यते । तद्य इष्टवाची परशब्दस्तस्येदं ग्रहणं 'विप्रतिषेधे परं यदिष्टं तद्भवति' इति ॥

(प्रदीपः) **तद्य इष्टवाचीति** । इष्टानिष्टविभागश्च व्याख्यानाद्बोध्यः ।

(उद्द्योतः) **व्यवस्थायामिति** तदाकाङ्क्षप्रवृत्तिनिमित्ते इत्यर्थः॥ ननु लक्षणचक्षुषां तद्विभागो दुर्ज्ञेयोऽत आह—**इष्टानिष्टेति** ॥

(अन्तरङ्गपरिभाषाधिकरणम्)

(१०२० आक्षेपवार्तिकम् ॥ ८ ॥)

॥ * ॥ अन्तरङ्गं च ॥ * ॥

(भाष्यम्) **अन्तरङ्गं च बलीयो भवतीति वक्तव्यम् ॥**

(प्रदीपः) **अन्तरङ्गं चेति** । अन्तर्मध्येऽङ्गानि निमित्तानि पारार्थ्याद्यस्य तदन्तरङ्गमित्युच्यते । एवं बहिरङ्गानि यस्य तद्बहिरङ्गम् । एतच्च न्यायसिद्धमेवानूदितम् । कार्यमित्यत्रार्हे कृत्यः । करणार्हं कार्यम् । तुल्यबलं च करणार्हमिति नित्यानित्योत्सर्गापवादान्तरङ्गबहिरङ्गेष्वस्य सूत्रस्याव्यापारः ॥

(उद्द्योतः) अङ्गशब्दस्य मुख्यो योऽर्थस्तस्य प्रकृतेऽभावादाह—**अन्तर्मध्ये इति** ॥ बहिरङ्गसमुदायस्य मध्येऽन्तर्भूतानीत्यर्थः ॥ अङ्गशब्दस्य निमित्तेषु प्रवृत्तौ निमित्तं दर्शयति—**पारार्थ्यादिति** । एवं चान्तर्भूतनिमित्तापेक्षमन्तरङ्गं बहिर्भूतनिमित्तापेक्षं च बहिरङ्गमिति भावः ॥ **एतच्च न्यायेति** । स च न्यायोऽन्यः परस्मिन्नित्यत्र भाष्ये दर्शितः ॥ **करणार्हं**, करणयोग्यम् ॥ **तुल्यबलं चेति** । यद्यपि विप्रतिषेधशब्देनेदमपि लब्धुं शक्यं तथापि तदेतदर्थबोधनेऽसमर्थमिति भावः । कदाचिल्लोके दुर्बलबलवतोरपि विरोधदर्शनात् ॥ **नित्यानित्येति** । नित्यस्य बलवत्त्वबीजं तु कृताकृतप्रसङ्गित्वेनावश्यकतैव । अन्तरङ्गं प्रथमं बुद्ध्यावारोहतीति तत्काले बहिरङ्गानुपस्थितेस्तदेव प्रथमं प्रवर्तते ॥ एवं च कचिद्भाष्ये **परत्वा**न्नित्यत्वाच्चेत्यादौ परत्वादित्युक्तिरेकदेशिन इति बोध्यम् ॥

(अनुयोगभाष्यम्)

किं प्रयोजनम् ॥

(१०२१ समाधानवार्तिकम् ॥ ९ ॥)

॥ * ॥ प्रयोजनं यणेकादेशेत्त्वोत्त्वानि गुणवृद्धिद्विर्वचनाल्लोपस्वरेभ्यः ॥ * ॥

(उदाहरणसमन्वयभाष्यम्)

गुणाद्यणादेशः—स्योनः स्योना । गुणश्च प्राप्नोति यणादेशश्च । परत्वाद्गुणः स्यात् । यणादेशो भवत्यन्तरङ्गतः ॥

(प्रदीपः) **स्योन इति** । सिवेर्बाहुलकान्नप्रत्यये कृतेऽपवादत्वाद्वलोपं बाधित्वा गुणात्पूर्वमन्तरङ्गत्वादूठ् भवति । तत्र कृतेऽन्तरङ्गत्वाद्यणा गुणो बाध्यते । बहिरङ्गस्याप्यूठो यणादेशे कर्तव्येऽसिद्धत्वं न भवति, **नाजानन्तर्ये** इति वचनात् ॥

(उद्द्योतः) **पूर्वमन्तरङ्गत्वादिति** । अन्तरङ्गत्वाभावेपि नित्यत्वेनोठ् सुसाध इत्युक्तं **येन विधिरिति** सूत्रे ॥ इदमुदाहरणमुणादिषु व्युत्पत्तिपक्षवादिनां शाकटायनादीनां मते ॥ **तत्रेऽन्तरङ्गत्वादिति** । अन्तर्भूतनिमित्तकत्वरूपादित्यर्थः ॥

(उदाहरणसमन्वयभाष्यम्)

वृद्धेर्यणादेशः—द्यौकामिः स्यौकामिः । वृद्धिश्च प्राप्नोति यणादेशश्च । परत्वाद् वृद्धिः स्यात् । यणादेशो भवत्यन्तरङ्गतः ॥

(प्रदीपः) **द्यौकामिरिति** । ननु कृतयणादेशात्तद्धितोत्पत्तौ वृद्ध्या भाव्यमिति नास्ति युगपद्यण्वृद्ध्योः प्राप्तिः । एवं तर्ह्यकृतव्यूहाः **पाणिनीया** इति दिउकाम इ इति स्थिते अत्र यण्वृद्ध्योर्युगपत्प्रसङ्गः ॥ अथवा द्यौकामिरिति पदं यदा विभज्यान्वाख्यायते—दिव्काम इ इति, तदा **दिव उत्** इत्युत्त्वे कृते यण्वृद्धी प्राप्नुतः ।

(उद्द्योतः) **युगपत्प्रसङ्ग इति** । अन्तरङ्गन्यायमनालोचयतः पूर्वपक्षिण इति शेषः ॥ नन्वकृतव्यूहपरिभाषा नास्त्येव । किं च तद्विषये नान्तरङ्गन्याय इति भाष्यासंगतिरित्यत आह—अथ

वेति। एवं चानयैव सिद्धे समर्थानामित्यत्र समर्थग्रहणं न कार्यमित्यभिप्रायः॥

(उदाहरणसमन्वयभाष्यम्)

द्विर्वचनाद्यणादेशः—दुद्यूषति सुस्यूषति। द्विर्वचनं च प्राप्नोति यणादेशश्च। नित्यत्वाद् द्विर्वचनं स्यात्। यणादेशो भवत्यन्तरङ्गतः।

(प्रदीपः) दुद्यूषतीति। दिवेः सन्। सनीवन्तर्धेति पक्षे इडभावः। हलन्ताच्चेति कित्त्वम्। ऊडादेशः। तत्र यण् च प्राप्नोति द्विर्वचनं च। नित्यत्वाद्द्विर्वचनं स्यात्॥ एतद्भाष्यं दूषयन्ति–'द्विप्रयोगो द्विर्वचनं षाष्ठिकं व्यवस्थापितम्। तत्र शब्दान्तरप्राप्त्या द्विर्वचनमनित्यं यण् तु नित्यः' इति वदन्तः॥

(उद्द्योतः) स्थाने द्विर्वचनपक्षे यणोपि शब्दान्तरप्राप्त्याऽनित्यत्वं स्यादत आह—द्विःप्रयोग इति॥ वदन्त इति। कृताकृतप्रसङ्गित्वमात्रेण कचिन्नित्यताभ्युपगमे तु यणोपि नित्यतया परत्वाद्यणेव स्यादिति तेषामाशयः॥ अन्ये तु द्विःप्रयोगपक्षेपि द्वितीयः प्रयोगो द्विर्वचननिष्पाद्यः पर एव। एवं च यस्य द्वित्वं न तस्य यण् तदनन्तरम्, किं तु द्वितीयस्य प्रयोगस्य। द्विर्वचनं तु यण्यपि कृते तस्यैव। नित्यशब्दवादे प्रयोगभेद एव शब्दभेदकः॥ एकप्रयोगे कृताकृतप्रसङ्ग्येव हि नित्यमिति भाष्याशयमाहुः॥

(उदाहरणविचारभाष्यम्)

अल्लोपस्य च यणादेशस्य च नास्ति संप्रधारणा।

(प्रदीपः) अल्लोपस्येति। ननु गाण्डीवधन्वनेस्यत्रास्ति सम्प्रधारणा। गाण्डीवधनु अन् आ इति स्थिते यदि पूर्वं यणादेशः ततो न संयोगाद्वमन्तादित्यल्लोपनिषेधाद्रूपं सिध्यति। अथ तु परत्वादल्लोपः स्यात्ततो यण् न स्यात्॥ एवं तर्हि नित्यत्वात्पूर्वमत्र यण् भवतीति मन्यते। कृतेप्यल्लोपे तस्य स्थानिवत्त्वाद्यणः प्राप्त्या नित्यत्वम्। यणि कृते नास्त्यल्लोपः प्रतिषेधादिति तस्यानित्यत्वम्॥

(उद्द्योतः) तस्यानित्यत्वमिति। यस्य लक्षणान्तरेण निमित्तं विहन्यते न तदनित्यमिति काचित्कमिति भावः॥

(उदाहरणसमन्वयभाष्यम्)

स्वराद्यणादेशः—द्यौकामिः स्यौकामिः। स्वरश्च प्राप्नोति यणादेशश्च। परत्वात्स्वरः स्याद्। यणादेशो भवत्यन्तरङ्गतः।

(प्रदीपः) द्यौकामिरिति। दि उ काम इ इति स्थिते यण् च प्राप्नोपि ञ्नित्यादिर्नित्यमिति स्वरश्च। तत्र यदि पूर्वं स्वरः स्यात्तदोदात्तस्वरितयोर्यण इत्यौकारः स्वरितः स्याद्, उदात्तश्चेष्यते॥ द्युकाम इति पूर्वपदप्रकृतिस्वरोपि यणा अन्तरङ्गत्वाद्बाध्यते तथैव दिव उदित्युत्वेन च॥

(उद्द्योतः) पूर्वपदप्रकृतीति। दिवि कामो यस्येति विग्रहे बहुव्रीहौ प्रकृत्येत्यनेनेत्यर्थः॥ ननूत्वे यण् इति ततः पूर्वमेव स्वरः स्यादत आह—तथैवेति।

(उदाहरणसमन्वयभाष्यम्)

गुणादेकादेशः—काद्रवेयो मन्त्रमपश्यत्। गुणश्च प्राप्नोत्येकादेशश्च। परत्वाद्गुणः स्यात्। एकादेशो भवत्यन्तरङ्गतः।

(प्रदीपः) काद्रवेय इति। कद्रुशब्दात् संज्ञायामित्यूङि कृते स्त्रीभ्यो ढक् द्व्यच इति ढकि एयादेशे ढे लोपोऽकद्र्वा इति लोपप्रतिषेधाद्दोर्गुण इति गुणश्च प्राप्नोत्येकादेशश्च॥ नन्वकृत एकादेशेऽप्रत्यय इति निषेधात् प्रातिपदिकत्वाभावात्तद्धित एव न स्यात्। कृते त्वेकादेशे तस्यान्तवद्भावात्प्रातिपदिकत्वात्तद्धितोत्पत्तिरित्यानुपूर्व्या सिद्धत्वादप्रयोजनमेतदित्याहुः। अत्रोच्यते—अकृतेप्येकादेशे नोङ्धात्वोरिति ढे लोपोऽकद्र्वा इति निषेधाच्च ज्ञापकाद्भविष्यति तद्धित इत्यदोषः॥

(उद्द्योतः) स्त्रीभ्य इति। यदि कद्रूर्नागमाता तदाऽनेन। यदि का चन मानुषी तदाऽवृद्धाभ्य इत्यणि प्राप्ते तदपवादो द्व्यच इति। एकादेशात्पूर्वं द्व्यच्त्वाभावे स्त्रीभ्य इत्यनेनैव ढक् कद्रूश्च नागमातैवेत्युचितम्॥ ज्ञापकादिति। स्त्रीभ्यो ढगित्यादौ प्रातिपदिकादित्यस्यासंबन्धेन लिङ्गविशिष्टपरिभाषया वा सिद्धेर्ज्ञापकपर्यन्तानुधावनं किमर्थमिति चिन्त्यम्। अत एवैणेयादौ ढक्सिद्धिरित्याहुः। ज्ञापकमपि चिन्त्यम्। अन्तरङ्गं बलवदित्येतज्ज्ञापनेन कृते एकादेशे तत्प्रवृत्त्या चारितार्थ्यसंभवात्॥

(उदाहरणसमन्वयभाष्यम्)

वृद्धेरेकादेशः—वैक्षमाणिः सौत्थितिः। वृद्धिश्च प्राप्नोत्येकादेशश्च। परत्वाद् वृद्धिः स्यात्। एकादेशो भवत्यन्तरङ्गतः॥

(उद्द्योतः) भाष्ये—परत्वाद्वृद्धिरिति। न च सा नित्या। शब्दान्तरप्राप्तत्वात्। इदमपि समर्थग्रहणप्रत्याख्यानतात्पर्यकम्॥

(उदाहरणसमन्वयभाष्यम्)

द्विर्वचनादेकादेशः—क्षाया ओदनः क्षौदनः। क्षौदनमिच्छति क्षौदनीयति। क्षौदनीयतेः सन्। जुक्षौदनीयिषति। द्विर्वचनं च प्राप्नोत्येकादेशश्च। नित्यत्वाद् द्विर्वचनं स्यात्। एकादेशो भवत्यन्तरङ्गतः।

(उद्द्योतः) नित्यत्वाद् द्विर्वचनमिति। भाष्ये शब्दान्तरप्राप्त्यानित्यत्वं तु काचित्कमिति भावः॥

(उदाहरणसमन्वयभाष्यम्)

अल्लोपादेकादेशः—शुना शुने। अल्लोपश्च प्राप्नो-

ल्येकादेशश्च । परत्वादल्लोपः स्यात् । एकादेशो भवत्यन्तरङ्गतः ॥

(प्रदीपः) **शुनेति** । ननु **श्वयुवेति** सम्प्रसारणे कृते तस्यासिद्धवदत्रेत्यसिद्धत्वान्न **संयोगाद्वमन्तादिति** निषेधादल्लोपस्य नास्ति प्राप्तिः ॥ एवं तर्हि **प्राग्भादित्यसिद्धत्वमा**श्रित्यैतदुक्तम् ॥

(उद्द्योतः) **एवं तर्हीति** । तस्य **श्नसोरल्लोप** इति तपरकरणेनानित्यत्वादनाश्रयणमिति वक्तुं युक्तम् ॥ **वार्णादाङ्ग**मित्यप्यनित्यत्वान्नाश्रितम् । न चान्तरङ्गपरिभाषाया अप्याभीयत्वेन तद्वृथा बहिरङ्गस्यासिद्धतया सर्वथा नेदमुदाहरणमिति वाच्यम् । **वाह ऊठ्**सूत्रज्ञापितासिद्धपरिभाषाया आभीयत्वेऽप्यन्तरङ्गं बलीय इत्यस्यास्तत्त्वे मानाभावात् । धर्मिग्राहकमानेन तां प्रति बहिरङ्गस्याभीयासिद्धत्वाप्रवर्तनाच्चेति दिक् ॥

(प्रयोजननिराकरणभाष्यम्)

नैतदस्ति प्रयोजनम् । नास्त्यत्र विशेषः अल्लोपेन वा निवृत्तौ सत्यां, पूर्वत्वेन वा ॥

(प्रदीपः) प्रयोजनप्रत्याख्यानवाद्याह—**नैतदस्तीति** ॥

(प्रयोजनाङ्गीकरणभाष्यम्)

अयमस्ति विशेषः अल्लोपेन निवृत्तौ सत्यामुदात्तनिवृत्तिस्वरः प्रसज्येत ॥

(प्रदीपः) प्रयोजनवाद्याह—**अयमस्तीति** ॥

(उद्द्योतः) भाष्ये—उदात्तनिवृत्तिस्वरः । **अनुदात्तस्य च यत्रोदात्तलोप** इत्यनेन ।

(प्रयोजननिराकरणभाष्यम्)

नात्रोदात्तनिवृत्तिस्वरः प्राप्नोति । किं कारणम् ?। "न गोश्वन्त्साववर्ण" इति प्रतिषेधात् ॥

(प्रदीपः) प्रत्याख्यानवाद्याह—**नात्रेति** ॥

(उद्द्योतः) **न गोश्वन्निति** । गवादिभ्यः परस्योदात्तत्वं नेत्यर्थः ॥

(प्रयोजनाङ्गीकरणभाष्यम्)

नैष उदात्तनिवृत्तिस्वरस्य प्रतिषेधः । कस्य तर्हि ? । तृतीयादिस्वरस्य ॥ यत्र तर्हि तृतीयादिस्वरो नास्ति शुनः पश्येति ।

(प्रदीपः) प्रयोजनवाद्याह—**नैष इति** ॥ स एवाह—**यत्र तर्हीति** । यत्र पुनरित्यर्थः ॥ **शुनः पश्येति** । अत्र हि **न गोश्वन्** इति प्रतिषेधाभावादल्लोपे सत्युदात्तनिवृत्तिस्वरप्रसङ्गः । तस्मात् पूर्वमेकादेश एष्टव्यः ॥

(उद्द्योतः) **तृतीयादिस्वरस्य** सावेकाच इति विहितस्य ॥ आनन्तर्यात्, तृतीयादिर्विभक्तिरित्यनुवर्त्तनाच्चेति भावः । एवं च सत्यल्लोपे उदात्तनिवृत्तिस्वरः स्यादिति प्रयोजनवाद्याशयः ॥ इत उत्तरो **यत्र तर्हीत्यादि**ग्रन्थो ग्रन्थच्छायया प्रत्याख्यानवादिन इति भाति, तत्तु न युक्तम् । तृतीयादिविभक्त्यभावेन **न गोश्वन्नि**त्यस्याप्रसक्तेरुदात्तनिवृत्तिस्वरो निष्प्रत्यूह इति फलभेदोपसंहारस्य तदपलापकप्रत्याख्यानवादिविरुद्धत्वादत आह—**स एवेति** । अयं भावः—तृतीयादिस्वानिकस्य लक्षणविशेषानादरेण सर्वस्य निषेध इत्याशङ्क्योदाहरणान्तरदानमिति ॥ नन्वेवं **तर्हि**शब्दो न युक्त इत्यत आह—**पुनरिति** । चेत्यर्थः । एतदर्थमेव तत्तदुक्तित्वेनादित भ्रान्तं तद्योजनमिति बोध्यम् ॥

(प्रयोजननिराकरणभाष्यम्)

एवं तर्हि न लाक्षणिकस्य प्रतिषेधं शिष्मः । किं तर्हि? येन केन चित्प्राप्तस्य विभक्तिस्वरस्य प्रतिषेधः।

(प्रदीपः) प्रत्याख्यानवाद्याह—**एवं तर्हीति** ॥

(उद्द्योतः) भाष्ये—**न लाक्षणिकस्येति** । तृतीयादिशब्दविशेषमुपादाय विहितस्येत्यर्थः ॥ भाष्ये—**विभक्तिस्वरस्येति** । तृतीयादिरिति नानुवर्त्तते, विभक्तिरित्येव । एवं च शुन् इत्यादावपि नास्ति फलभेद इत्यर्थः ॥

(प्रयोजनाङ्गीकारभाष्यम्)

यत्र तर्हि विभक्तिर्नास्ति बहुशुनीति ॥

(प्रदीपः) प्रयोजनवाद्याह—**यत्र तर्हीति** । **बहुशुनीति** । **बहोर्नञ्वदुत्तरपदभूम्नीत्यन्तोदात्तस्तस्मान्ङीपि** कृतेऽल्लोपे क्रियमाण उदात्तनिवृत्तिस्वरः स्यात् ॥

(उद्द्योतः) ननु बहुश्वन्शब्दस्य बहुव्रीहित्वेन पूर्वपदप्रकृतिस्वरत्वादुदात्तनिवृत्तिस्वराप्राप्तिरत आह—**बहोरिति** । प्रत्याख्यानवादिनाऽल्लोपस्यैवेष्टत्वेन तद्रीत्या ऽन उपधेत्यस्य प्राप्तिं मत्वा बहुशुनीत्युदाहृतम् ॥

(प्रयोजननिराकरणभाष्यम्)

यदि पुनरयमुदात्तनिवृत्तिस्वरस्यापि प्रतिषेधो विज्ञायेत ॥

(प्रदीपः) प्रत्याख्यानवाद्याह—**यदि पुनरिति** ॥

(उद्द्योतः) भाष्ये—**यदि पुनरिति** । विभक्तिग्रहणमपि नानुवर्त्तते इति भावः ॥

(प्रयोजनाङ्गीकारभाष्यम्)

नैवं शक्यम् । इहापि प्रसज्येत कुमारीति ॥

(प्रदीपः) प्रयोजनवाद्याह—**नैवं शक्यमिति** । कुमारशब्दः साववर्णान्त इति ङीप उदात्तस्वरो न स्यात् ॥

(उद्द्योतः) **कुमारशब्द इति** । तस्माद्विभक्तिग्रहणमनुवर्त्तते, तथाच बहुशुनीत्यत्रोदात्तनिवृत्तिस्वरः स्यादिति भावः ॥

(प्रयोजननिराकरणभाष्यम्)

एवं तर्हि आचार्यप्रवृत्तिर्ज्ञापयति—नोदात्तनिवृत्तिस्वरः शुन्यवतरतीति । यदयं श्वन्शब्दं गौरादिषु पठति अन्तोदात्तार्थं यत्नं करोति । सिद्धं हि स्यान्ङीपैव ॥

(प्रदीपः) प्रत्याख्यानवाद्याह—**एवं तर्हीति** । शुनीत्यत्र ङीप उदात्तनिवृत्तिस्वरस्य सिद्धत्वात्किं ङीप्विधानेनेत्यर्थः । तदेवमल्लोपादेकादेशस्य स्वरार्थत्वं दूषितम् प्रयोजनान्तरं त्वस्त्येव । यद्यत्राल्लोपो भवति तदाऽन **उपधालोपिन** इति ङीपि सति बहुशुनीति भवति । यदा त्वेकादेशेनाल्लोपो बाध्यते तदोपधालोपित्वाभावान्ङीबभावाद्बहुश्वेति । गौरादिलक्षणो ङीष् नास्ति । **अनुपसर्जना**दित्यधिकारात् । भाष्ये तु बहुशुनीति प्रत्याख्यानवादिमतेनोपन्यस्तम् । तत्पक्षे किल ङीपा भाव्यमिति । न्यायमूलं चेदमन्तरङ्गं **बलीय** इति । न च न्यायस्यात्र केनचिद्बाधोऽस्तीति बहुश्वेत्येव भाव्यमिति न्यायविद आहुः ॥

(उद्योतः) **बहुश्वेतीति । डाबुभाभ्यामिति** डापि तदभावे चेति भावः ॥ नन्वेवं प्रयोजनवादिग्रन्थे बहुशुनीत्ययुक्तमत आह—**भाष्ये त्विति** । ननु प्रत्याख्यानान्ततयैवात्रत्यग्रन्थपर्यवसानात् । **असिद्धवत्सूत्र**स्थैतदानुपूर्वीकभाष्याच्च बहुशुनीति भगवत इष्टमिति भ्रमं वारयति—**न्यायेत्यादिना** ॥ ननु भाष्यमेव न्यायबाधकमस्त्वित्यत आह—**न्यायविद इति** । भाष्यस्योदात्तनिवृत्तिस्वरकृतस्वरवैलक्षण्यपरिहारमात्रतात्पर्यकतया न न्यायबाधकत्वम् । **डाबुभाभ्या**मितिसूत्रस्थभाष्यरीत्या बहुश्वेत्येव भाष्यसंमतमिति भावः । न चाल्लोपे सति तस्य स्थानिवत्त्वाद्यण् स्यादिति कुतो नापादितः । **यूनस्तिः शुनः पुच्छे**त्यादिनिर्देशैर्वारणसंभवात् ॥ वस्तुतो लोपे सर्वानुदात्तं शुनेति प्राप्नोति पूर्वरूपे त्वेकादेशस्वरेणाद्युदात्तमित्यपि विशेषो बोध्यः ॥

(उदाहरणसमन्वयभाष्यम्)

स्वरादेकादेशः । सौत्थितिः वैक्षमाणिः । स्वरश्च प्राप्नोत्येकादेशश्च । परत्वात्स्वरः स्याद् । एकादेशो भवत्यन्तरङ्गतः ।

(प्रदीपः) **सौत्थितिरिति** । सु उत्थित इ इति स्थिते यद्यत्र पूर्वमुकारस्योदात्तत्वं स्यात् तदा **स्वरितो वानुदात्ते पदादा**विति पक्षे स्वरितत्वं प्रसज्येत । पूर्वं त्वेकादेशे कृते नित्यमाद्युदात्तमेतद्भवति ।

(उद्योतः) ननु पूर्वमुदात्तत्वेपि तदेकादेशस्यैकादेश उदात्तेनेत्यनेनोदात्तत्वे इष्टसिद्धेराह—**तदेति । नित्यमिति** । ञ्नित्यादिरित्यनेनेति भावः । एतदपि प्रयोजनं समर्थग्रहणप्रत्याख्यानाभिप्रायेण ॥

(उदाहरणविचारणाभाष्यम्)

गुणस्य चेत्त्वौत्त्वयोश्च नास्ति संप्रधारणा ॥

(प्रदीपः) **गुणस्येति** । परत्वाद्धि गुणेन भाव्यम् ॥

(उद्योतः) **परत्वाद्धीति** । इदं वस्तुतत्त्वकथनं न तु संप्रधारणाभावे हेतुः । स तूभयोरपि बहिर्भूतप्रत्ययापेक्षत्वेन समत्वेनान्तरङ्गत्वाभाव इति बोध्यम् ।

(उदाहरणसमन्वयभाष्यम्)

वृद्धेरित्त्वोत्त्वे । स्तैर्णिः पौर्तिः । वृद्धिश्च प्राप्नोतीत्त्वोत्त्वे च । परत्वाद् । वृद्धिः स्याद् इत्त्वोत्त्वे भवतोन्तरङ्गतः ॥

(प्रदीपः) **स्तैर्णिरिति** । विभज्यान्वाख्याने स्तृत इ इति स्थितेऽन्तरङ्गत्वादित्त्वं ततो वृद्धिः ।

(उद्योतः) ननु स्तीर्णशब्दादिञि न दोषोऽत आह—**विभज्येति** ।

(उदाहरणसमन्वयभाष्यम्)

द्विर्वचनादित्त्वोत्त्वे । आतेस्तीर्यते आपोपूर्यते । द्विर्वचनं च प्राप्नोतीत्त्वोत्त्वे च । नित्यत्वाद् द्विर्वचनं स्यात् । इत्त्वोत्त्वे भवतोऽन्तरङ्गतः ।

(उद्योतः) भाष्ये—**इत्त्वोत्त्वे भवतोऽन्तरङ्गत इति** । अत्रैकाच्त्वानभ्यासत्वप्रथमत्वादिबहूपाध्यपेक्षत्वेन द्वित्वस्य बहिरङ्गत्वं बोध्यम् । इदं प्रयोजनमेकदेश्युक्तिः । द्वयोर्नित्यत्वेऽनित्यत्वे वा परत्वादित्त्वादिसिद्धेः । यङन्तस्य द्वित्वेन तस्यापरनिमित्तकत्वेनान्तरङ्गत्वाच्चेत्यन्ये ॥

(उदाहरणविचारभाष्यम्)

अल्लोपस्य चेत्त्वोत्त्वयोश्च नास्ति संप्रधारणा । स्वरे नास्ति विशेषः ॥

(प्रदीपः) **स्वर इति** । स्तैर्णिरिति यदि पूर्वं स्वरः तत इत्त्वं तथाप्यान्तरतम्यादुदात्तत्वं सिद्ध्यति ॥

(उद्योतः) स्वरेणापीत्त्वोत्त्वयोर्नास्ति संप्रधारणेत्याह—**स्वरे नास्तीति** ॥

(१०२२ प्रयोजनवार्तिकम् ॥ १० ॥)

॥ * ॥ इण्ङिशीनामाद्गुणः सवर्णदीर्घत्वात् ॥ * ॥

(भाष्यम्) **इण्ङिशीनामाद्गुणः सवर्णदीर्घत्वात् प्रयोजनम् । अयज इन्द्रम् अवप इन्द्रम् । वृक्षइन्द्रं प्लक्षइन्द्रं तइन्द्रं । यइन्द्रम् । आद् गुणश्च प्राप्नोति सवर्णदीर्घत्वं च । परत्वात्सवर्णदीर्घत्वं स्यात् । आद्गुणो भवत्यन्तरङ्गतः ।**

(१०२३ प्रयोजननिराकरणवार्तिकम् ॥ ११ ॥)

॥ * ॥ न वा सवर्णदीर्घत्वस्यानवकाशत्वात् ॥ * ॥

(भाष्यम्) **न वा एतदन्तरङ्गेणापि सिद्ध्यति । किं कारणम् ? । सवर्णदीर्घत्वस्यानवकाशत्वात् । अनवकाशं सवर्णदीर्घत्वमाद्गुणं बाधेत ॥**

(प्रदीपः) **न वेति** । दण्डाग्रमित्याद्गुणः प्राप्नोति । कुमारी ईहत इत्यादौ यणादेश इत्यवश्यं सवर्णदीर्घत्वेन विध्यन्तरं बाध्यम् ।

(उद्योतः) ननु कुमारीहते दण्डाग्रमित्यादौ सावकाशं दीर्घत्वमत आह—**दण्डाग्रमिति** । एवं च यण्गुणाभ्यां सर्वविष-

यन्यासैरवश्यं विध्यन्तरे बाध्ये बाध्यसामान्यचिन्तयाऽगृह्यमाणविशेषत्वात्सर्वं बाध्यमित्यर्थः ॥

(प्रयोजनाङ्गीकरणभाष्यम्)

नैतदन्तरङ्गेऽस्ति—अनवकाशं परमिति । इहापि स्योनः स्योनेति शक्यं वक्तुम् । न वा परत्वाद् गुणस्येति ।

(प्रदीपः) **नैतदिति** । एकनिमित्तप्राप्तविध्यन्तरबाधनेन सावकाशः सवर्णदीर्घोऽन्तरङ्गं बाधितुं न शक्नोतीति भावः । निरवकाशेन तु विध्यन्तरेण सावकाशोऽन्तरङ्गोपि विधिर्बाध्यते यथा **गोत्रेऽलुगचीत्यलुका लुक्** ॥ **न वा परत्वादिति** । यथा त्वत्र परत्वेन न व्यवस्था अपि त्वन्तरङ्गत्वेन तथा आद्गुणोपि समानकक्ष्यो दीर्घेण बाध्यते न त्वन्तरङ्ग इति भावः ॥

(उद्द्योतः) अन्तरङ्गादपि निरवकाशस्य बलवत्त्वेन नैतदन्तरङ्ग इत्यनुपपन्नमत आह—**एकनिमित्तेति** । एकस्थानिकेत्यपि बोध्यम् । एवं च स्वसमाननिमित्तकेन स्वसमानस्थानिकेनैव च **येन नाप्राप्तिन्यायो** न तु विभिन्नस्थानिनिमित्तकेनापीति न तद्बाध इति भावः ॥ यस्तु सर्वथाऽनवकाशः स बाधक एवेत्याह—**निरवकाशेनेति** । एकस्थानिनिमित्तकेनेत्यर्थः । बहिर्भूताजादिप्रत्ययापेक्षत्वादलुक् बहिरङ्गः ॥ भाष्ये—**इहापीति** । यद्यन्तरङ्गेपीदं स्यात् तर्हि तत्राप्यन्तरङ्गत्वबाधणं न स्यात् गुणस्य परत्वादिति बाधकतर्केण समाननिमित्तकमेव निरवकाशपराभ्यां बाध्यत इति द्रढितम् ॥ फलितमाह—**यथा त्विति** ॥

(१०२४ प्रयोजनवार्तिकम् ॥ १२ ॥)

॥ * ॥ ऊङापोरेकादेश ईत्त्वलोपाभ्याम् ॥ * ॥

(उदाहरणसमन्वयभाष्यम्)

ऊङापोरेकादेश ईत्त्वलोपाभ्यां भवत्यन्तरङ्गतः ॥ प्रयोजनम् । ईत्त्वादेकादेशः । खट्वीयति मालीयति । ईत्त्वं च प्राप्नोत्येकादेशश्च । परत्वादीत्त्वं स्याद् । एकादेशो भवत्यन्तरङ्गतः ॥

(प्रदीपः) **खट्वीयतीति** । खट्व आ य इति स्थिते यदि पूर्वमीत्त्वं स्यात् तत **आद्गुणः** प्रसज्येत ॥ नन्वाकारस्य कृते ईत्त्वे **यस्येति** लोपो भविष्यति । नैतदस्ति । **पूर्वविधाविति**त्वस्य स्थानिवद्भावात् ॥

(उद्द्योतः) ननु खट्वाशब्दे सुबुत्पत्तेः प्रागेवैकादेशोऽत आह—**खट्व आ इति** । विभज्यान्वाख्याने दोषः ॥ सुप् लिङ्गविशिष्टपरिभाषयेति भावः ॥ **लोप इति** । खट्वशब्दाकारस्येत्यर्थः ॥

(उदाहरणसमन्वयभाष्यम्)

लोपादेकादेशः—कामण्डलेयः । माद्रबाहेयः । लोपश्च प्राप्नोत्येकादेशश्च । परत्वाल्लोपः स्याद् । एकादेशो भवत्यन्तरङ्गतः ॥

(आक्षेपभाष्यम्)

अथ किमर्थम् 'ईत्त्वलोपाभ्याम्' इत्युच्यते, न 'लोपेत्त्वाभ्याम्' इत्येवोच्येत ?।

(प्रदीपः) **न लोपेत्त्वाभ्यामिति** । ऊङ ईत्त्वासम्भवादयं क्रमोऽयुक्त आश्रयितुमिति भावः ॥ **यद्यप्यजाद्यदन्तमिति** ईत्त्वशब्दस्य पूर्वनिपातो न्याय्यः । तथापि **लक्षणे** प्रायेणासौ नाद्रियते ॥

(उद्द्योतः) नन्वजाद्यदन्तत्वादीत्त्वशब्दस्यैव पूर्वनिपातो युक्तोऽत आह—**ऊङ इति** । **न्याय्य इति** । शास्त्रीयत्वात् क्रमबाध्योऽपि सोढव्य इति भावः ॥ **लक्षणे इति** । **अन्तिकबाढयोर्नेदसाधावित्यादिनिर्देशैः** क्रमानुसारस्य सर्वपूर्वनिपातविधिभ्यो बलवत्त्वज्ञापनादिति भावः ॥

(समाधानभाष्यम्)

संख्यातानुदेशो मा भूदिति ॥

(उद्द्योतः) भाष्ये—**संख्यातानुदेश इति** । ननु नात्र **यथासंख्यसूत्रप्राप्तिस्तस्य** विध्यङ्गत्वाद्, नापि स्थानाख्यप्रमाणस्य समासनिर्देशादिति चेन्न । अनूद्यमानयोरपि तत्प्रवृत्तेरुक्तत्वादिति भावः ॥

(समाधानसाधकभाष्यम्)

आपोप्येकादेशो लोपे प्रयोजयति—चौडिः बालाकिः ।

(प्रदीपः) **चौडिरिति** । पूर्वमाकारलोपे सति तस्य स्थानिवत्त्वादसिद्धत्वाद्वाकारलोपाभावाद्गुण इति गुणस्य प्रसङ्गः ॥

(उद्द्योतः) **असिद्धत्वाद्वेति** । चिणोलुग्न्यायेनात्राभीयासिद्धत्वं बोध्यम् ॥

(१०२५ प्रयोजनवार्तिकम् ॥ १३ ॥)

॥ * ॥ आत्त्वनपुंसकोपसर्जनह्रस्वत्वान्ययवायावेकादेशतुग्विधिभ्यः ॥ * ॥

(भाष्यम्) **आत्त्वनपुंसकोपसर्जनह्रस्वत्वानि अयवायावेकादेशतुग्विधिभ्यो भवत्यन्तरङ्गतः । वेञ् वानीयम् । शो शानीयम् । ग्लै ग्लानीयम् । म्लै म्लानीयम् । ग्लाछत्रम् । म्लाछत्रम् । आत्त्वं च प्राप्नोत्येते च विधयः । परत्वादेते विधयः स्युः । आत्त्वं भवत्यन्तरङ्गतः ॥**

(प्रदीपः) **ग्लानीयमिति** । विभज्यान्वाख्याने ग्लै अनीय इति स्थितेऽनैमित्तिकत्वादात्त्वमन्तरङ्गं भवति । **ग्लाछत्रमिति** ग्ला म्ला इति क्विबन्तम् । अत्रापि तथा विभज्यान्वाख्याने ग्लै छत्रमिति स्थिते यदि पूर्वं तुक् स्यात्तदैजन्तत्वाभा-

वादात्त्वं न स्याद् यथा ढौकितेति ॥ उपदेशग्रहणानपेक्षया चैतदुदाहरणम् ॥

(उद्योतः) ननूपदेशे आत्वमनैमित्तिकमयादयस्तु प्रत्ययोत्पत्त्यनन्तरभाविन इति संप्रधारणाभावादाह—**विभज्येति** । अशितीति प्रसज्यप्रतिषेध इति भावः ॥ **क्विबन्तमिति** । कर्तरि क्विन्तेन षष्ठीसमास इत्यर्थः ॥ **नपेक्षयेति** । एवं चैतत्प्रयोजनमेकदेश्युक्तिरिति भावः ॥

(उदाहरणसमन्वयभाष्यम्)

नपुंसकोपसर्जनह्रस्वत्वं च प्रयोजनम् । अतिर्यत्र । अतिन्वत्र । अतिरिच्छत्रम् । अतिनुच्छत्रम् । आराशस्त्रीदम् । धानाशष्कुलीदम् । निष्कौशाम्बीदम् । निर्वाराणसीदम् । निष्कौशाम्बिच्छत्रम् । निर्वाराणसिच्छत्रम् । नपुंसकोपसर्जनह्रस्वत्वं च प्राप्नोत्येते विधयश्च । परत्वादेते विधयः स्युः । नपुंसकोपसर्जनह्रस्वत्वं भवत्यन्तरङ्गतः ॥

(प्रदीपः) **अतिर्यत्रेति** । अतिरि अत्र इति स्थिते आयादेशे सत्यनजन्तत्वाद्ध्रस्वो न स्यात् ॥ **आराशस्त्रीदमिति** । आराशस्त्री इदमिति स्थिते यद्यत्र पूर्वमेकादेशः स्यात्तदा तस्यान्तवद्भावाद् ह्रस्वे कृते रूपं न सिद्ध्येत् ॥

(उद्योतः) **अन्तवदिति । स नपुंसकमिति** नपुंसकत्वस्यापि शास्त्रीयत्वादतिदेश इति भावः ॥

(१०२६ प्रयोजनवार्तिकम् ॥ १४ ॥)

॥ * ॥ तुग्यणेकादेशगुणवृद्ध्यौत्त्वदीर्घत्वमुमेत्त्वरीविधिभ्यः ॥ * ॥

यणेकादेशगुणवृद्ध्यौत्त्वदीर्घत्वेत्त्वमुमेत्त्वरीविधिभ्यस्तुग् भवत्यन्तरङ्गतः । यणादेशात्—अग्निचिदत्र । सोमसुदत्र ॥ एकादेशात्—अग्निचिदिदम् । सोमसुदुदकम् ॥ गुणात्—अग्निचिते सोमसुते ॥ वृद्धेः—प्रक्रच्छकः प्राच्छेकः ॥ औत्त्वात्—अग्निचिति सोमसुति ॥ दीर्घत्वात्—जगद्भ्याम् । जनगद्भ्याम् ॥ इत्त्वात्—जगत्यति जनगत्यति ॥ मुमः—अग्निचिन्मन्यः सोमसुन्मन्यः ॥ एत्त्वात्—जगद्भ्यः जनगद्भ्यः ॥ रीविधेः—सुकृत्यति पापकृत्यति ॥ [तुक् च प्राप्नोत्येते विधयश्च । परत्वादेते विधयः स्युः । तुग्भवत्यन्तरङ्गतः] ॥

(प्रदीपः) **अग्निचिदत्रेति** । पदसमुदायस्य विभज्यान्वाख्याने अग्निचि-अत्र इति स्थिते यदि पूर्वं यण् स्यात् तदा तुङ् न स्यात् । नपुंसकं चात्राग्निचि इति द्रष्टव्यम् । पुंसि विभक्त्या व्यवधानात् ॥

(उद्योतः) **पदसमुदायस्येति । पदस्य पदादित्यादौ** पदसमुदायस्याप्यन्वाख्यानदर्शनादिति भावः ॥ **पुंसि विभक्त्येति ।** न च सुबपेक्षया परत्वात्प्रथमं तुगिति कथं सुपा व्यवधानोक्तिरिति वाच्यम् । अग्निचिते इत्यादौ गुणतुकोः संप्रधारणाया अग्रे भाष्ये कृतत्वेन तुकः पूर्वमन्तरङ्गत्वाद्विभक्ति सिद्धवत्कृत्यैवास्य भाष्यस्य प्रवृत्तिरित्याशयात् ॥ भाष्ये **प्रक्रच्छकः प्राच्छेक इति । एत्वतु**कोरित्यनपेक्ष्येदम् ॥ बहिरङ्गत्वेनापि सिध्यति । **नाजानन्तर्ये** इति तु नास्त्येवेत्यभिप्रायः ॥

(१०२७ प्रयोजनवार्तिकम् ॥ १५ ॥)

[॥ * ॥ अनङानङ्भ्यां च ॥ * ॥]

(भाष्यम्) **अनङानङ्भ्यां चेति वक्तव्यम् ॥ अनङ्—सुकृत् । आनङ्—सुकृदुष्कृतौ । [तुक् प्राप्नोति अनङानङौ च । परत्वादनङानङौ स्याताम् । तुग्भवत्यन्तरङ्गतः ॥]**

(प्रदीपः) **सुकृद्दुष्कृताविति** । कथं पुनरत्रानङ् प्राप्नोति । यावता विद्यायोनिसम्बन्धवाचिनामृदन्तानां द्वन्द्वे स विहित इति चिन्त्यमेतत् ॥

(उद्योतः) **चिन्त्यमेतदिति** । सुकृदादिशब्दयोः प्रकरणादिना यदा ऋत्विग्विशेषे पर्यवसानं तदेदमुदाहरणमित्याहुः ॥

(१०२८ प्रयोजनवार्तिकम् ॥ १६ ॥)

॥ * ॥ इयङादेशो गुणात् ॥ * ॥

(भाष्यम्) **इयङादेशो गुणाद्भवत्यन्तरङ्गतः । प्रयोजनम् । धियति रियति । इयङादेशः प्राप्नोति गुणश्च । परत्वाद्गुणः स्यात् । इयङादेशो भवत्यन्तरङ्गतः ॥**

(प्रदीपः) **धियतीति** । धि धारणे तिपि शे कृते तिबाश्रयो गुणः प्राप्नोति । विकरणाश्रय इयङ् भवत्यन्तरङ्गत्वात् ॥

(उद्योतः) ननु शस ङित्वाद्गुणस्य कथं प्राप्तिर्द्वयोरप्येकनिमित्तत्वेनान्तरङ्गत्वाद्यभावश्चेत्यत आह—**तिबाश्रय इति । गुणो,** लघूपधगुणः ॥

(१०२९ प्रयोजनवार्तिकम् ॥ १७ ॥)

[॥ * ॥ उवङादेशश्च ॥ * ॥]

(भाष्यम्) **उवङादेशश्चेति वक्तव्यम् । प्रादुधुवत् । प्रासुसुवत् ।**

(१०३० प्रयोजनवार्तिकम् ॥ १८ ॥)

॥ * ॥ श्वेः संप्रसारणपूर्वत्वं यणादेशात् ॥ * ॥

(भाष्यम्) श्वेः संप्रसारणपूर्वत्वं यणादेशाद् भवत्यन्तरङ्गतः ॥ प्रयोजनम्--शुशुवतुः । शुशुवुः । पूर्वत्वं च प्राप्नोति यणादेशश्च । परत्वाद्यणादेशः स्यात् । पूर्वत्वं भवत्यन्तरङ्गतः ॥

(प्रदीपः) यणादेशश्चेति । एरनेकाचं इति यण् ॥

(उद्द्योतः) एरिति । इको यणिति त्वियङा बाधितमिति भावः । उस्यानिकयणस्तु पूर्वरूपमपवाद इति तात्पर्यम् ॥

(१०३१ प्रयोजनवार्तिकम् ॥ १९ ॥)

॥ * ॥ ह्व आकारलोपात् ॥ * ॥

(भाष्यम्) ह्व आकारलोपात् पूर्वत्वं भवत्यन्तरङ्गतः । प्रयोजनम्—जुहुवतुः जुहुवुः । पूर्वत्वं च प्राप्नोत्याकारलोपश्च । परत्वादाकारलोपः स्यात् । पूर्वत्वं भवत्यन्तरङ्गतः ॥

(प्रदीपः) जुहुवतुरिति । ह्वा अतुस् । ह्वः सम्प्रसारणमभ्यस्तस्य चेति सम्प्रसारणे कृते यद्याकारस्य लोपः स्यात्तदा स्थानिवत्त्वादसिद्धवदत्राभादित्यसिद्धत्वाद्वोवङ् न स्यात् ॥

(उद्द्योतः) यद्याकारेति । ननु कृदतिङ्मत्रस्याकाररीत्या चिकीर्षतीत्यादावचः परस्मिन्निति स्थानिवत्त्वेन तुगभाववद् जुहुवतुरित्यत्र पूर्वरूपेपि तस्य स्थानिवत्त्वादुवङोऽप्राप्तिरिति चेन्न । पूर्वस्य धातुत्वाभावेन तदुद्देश्यकविधेरभावादित्याहुः ।

(१०३२ प्रयोजनवार्तिकम् ॥ २० ॥)

॥ * ॥ स्वरो लोपात् ॥ * ॥

(भाष्यम्) स्वरो लोपाद्भवत्यन्तरङ्गतः । प्रयोजनम् । औपगवी । सौदामनी । स्वरश्च प्राप्नोति लोपश्च । परत्वाल्लोपः स्यात् । स्वरो भवत्यन्तरङ्गतः।

(प्रदीपः) औपगवीति । उपगोरियमित्यणि ङीपि च कृते यदि प्रत्ययाद्युदात्तत्वात्पिदनुदात्तत्वाद्वा पूर्वं लोपः स्यात्तदोदात्तनिवृत्तिस्वर ईकारस्य न स्यात् ॥

(उद्द्योतः) उपगोरियमिति । अनन्तरापत्यमिति शेष इत्येके । गोत्राणि तु जातित्वान्ङीषेव स्यादिति न स्वरः प्रयोजनमिति भावः ॥ प्रत्ययाद्युदात्तत्वादिति । एतदणः ॥ पिदनुदात्तत्वाद्वेति ॥ एतन्ङीपः ॥ पिदनुदात्तत्वमप्युभयापेक्षलोपादन्तरङ्गमेवेति बोध्यम् ॥

(१०३३ प्रयोजनवार्तिकम् ॥ २१ ॥)

॥ * ॥ प्रत्ययविधिरेकादेशात् ॥ * ॥

(भाष्यम्) प्रत्ययविधिरेकादेशाद्भवत्यन्तरङ्गतः । प्रयोजनम्—अग्निरिन्द्रः वायुरुदकम् । प्रत्ययविधिश्च प्राप्नोत्येकादेशश्च । परत्वादेकादेशः स्यात् । प्रत्ययविधिर्भवत्यन्तरङ्गतः ॥

(प्रदीपः) अग्निरिन्द्र इति । यद्यपि प्रत्ययरहितायाः प्रकृतेः प्रयोगो नास्ति तथापि वाक्यस्य विभज्यान्वाख्याने क्रियमाणेऽयं विचारः क्रियते । यद्यपि प्रत्ययस्य नित्यत्वं तथाप्यन्तरङ्गत्वेनैव सिद्धत्वान्न तदाश्रितम् ॥

(उद्द्योतः) प्रत्ययस्येति । एकादेशेपि पूर्वान्तवत्त्वेन सुपः प्राप्तेस्तस्य नित्यत्वम् ॥

(१०३४ प्रयोजनवार्तिकम् ॥ २२ ॥)

॥ * ॥ यणादेशाच्च ॥ * ॥

(भाष्यम्) यणादेशाच्चेति वक्तव्यम् । अग्निरत्र वायुरत्र ॥

(१०३५ प्रयोजनवार्तिकम् ॥ २३ ॥)

॥ * ॥ लादेशो वर्णविधेः ॥ * ॥

(भाष्यम्) लादेशो वर्णविधेर्भवत्यन्तरङ्गतः । प्रयोजनम् । पचत्वत्र पठत्वत्र । लादेशश्च प्राप्नोति यणादेशश्च । परत्वाद्यणादेशः स्यात् । लादेशो भवत्यन्तरङ्गतः ।

(प्रदीपः) पचत्वत्रेति । यद्यत्र पूर्वं यण् स्याद् अनल्विधाविति स्थानिवत्त्वनिषेधादुत्वं न स्यात् ॥

(उद्द्योतः) भाष्ये—परत्वाद्यणिति । शब्दान्तरप्राप्तेर्नित्यत्वं नोक्तम् । लादेशशब्देन लादेशस्थानिक आदेशस्तदाह—उत्वं नेति ॥

(१०३६ प्रयोजनवार्तिकम् ॥ २४ ॥)

॥ * ॥ तत्पुरुषान्तोदात्तत्वं पूर्वपदप्रकृतिस्वरात् ॥ * ॥

(भाष्यम्) तत्पुरुषान्तोदात्तत्वं पूर्वपदप्रकृतिस्वराद्भवत्यन्तरङ्गतः । प्रयोजनं पूर्वशालाप्रियः अपरशालाप्रियः । तत्पुरुषान्तोदात्तत्वं च प्राप्नोति पूर्वपदप्रकृतिस्वरत्वं च । परत्वात्पूर्वपदप्रकृतिस्वरत्वं स्यात् । तत्पुरुषान्तोदात्तत्वं भवत्यन्तरङ्गतः ।

(प्रदीपः) पूर्वशालाप्रिय इति । पूर्वा शाला प्रिया अस्येति त्रिपदे बहुव्रीहौ कृते तद्धितार्थेति द्वयोः पदयोस्तत्पुरुषः । तत्र त्रिपदाश्रयबहुव्रीहिनिमित्तः पूर्वपदप्रकृति

स्वरो बहिरङ्गत्वान्न प्रवर्तते । तेन तत्पुरुषसमासाश्रयं शालाशब्दस्यान्तोदात्तत्वं भवति । पूर्वशब्दः **स्वाङ्गशिटामदन्तानामित्याद्युदात्तः** ।

(उद्योतः) **तत्रेति** । यद्यपि सति शिष्टत्वादिदं सिद्धं तथाप्यन्तरङ्गन्यायादपीष्टसिद्धिरिति भावः ॥

(उपसंहारभाष्यम्)

एतान्येतस्याः परिभाषायाः प्रयोजनानि यदर्थमेषा परिभाषा कर्तव्या ॥

(सिद्धान्तिभाष्यम्)

यदि सन्ति प्रयोजनानीत्येषा क्रियते ॥ ननु चेयं च कर्तव्या "असिद्धं बहिरङ्गलक्षणमन्तरङ्गलक्षणे" इति । किं प्रयोजनम् ? । पचावेदम् । पचामेदम् । बहिरङ्गलक्षणगुणस्यान्तरङ्गलक्षणमैत्वं मा भूदिति ॥

(प्रदीपः) **पचावेदमिति** । अन्तरङ्गबलीयस्त्वेनैतन्न सिद्ध्यति । बहिरङ्गे कृते आद्गुणे एत ऐ इति प्राप्नोति ॥

(उद्योतः) **बहिरङ्गे कृते इति** । अयं हि न्यायो युगपत्प्राप्तावन्तरङ्गस्य प्रथमं प्रवृत्तिबोधक एवेति भावः ।

(तृतीयाक्षेपभाष्यम्)

उभे तर्हि कर्तव्ये ॥

(सिद्धान्तिभाष्यम्)

नेत्याह । अनयैव सिद्धम् । इहापि स्योनः स्योनेति असिद्धत्वाद्बहिरङ्गलक्षणस्य गुणस्यान्तरङ्गलक्षणो यणादेशो भविष्यति ॥

(प्रदीपः) **अनयैवेति** । इयं हि व्यापिका । पूर्वोक्तप्रयोजननिष्पादनात् । शास्त्रासिद्धत्वाश्रयणाद्बहिरङ्गलक्षणं न तावत्प्रवर्तते । अन्तरङ्गलक्षणे तु प्रवृत्ते यत्र निमित्तसद्भावस्तत्र बहिरङ्गलक्षणप्रवृत्तिः ॥

(उद्योतः) **पूर्वोक्तेति** । अन्तरङ्गे कर्तव्ये बहिरङ्गमसिद्धम् । तद्बहिरङ्गं कृतं चिकीर्षितं वेत्यन्यत् ॥ ननु स्योन इत्यत्र परत्वाद्गुणे तस्यासिद्धत्वेपीकोऽभावाद्यण् न स्यादत आह—**शास्त्रेति** ॥ नन्वेवं सौत्थितिरित्यादौ स्योने गुणशास्त्रवद्बहिरङ्गमाद्युदात्तशास्त्रं न प्रवर्तेतेत्यत आह—**अन्तरङ्गे चेति** । युगपत् प्राप्तौ बहिरङ्गस्य न पूर्वं प्रवृत्तिः, प्रवृत्ते त्वन्तरङ्गे भवत्येव बहिरङ्गमिति भावः ॥

(आक्षेपभाष्यम्)

यदि 'असिद्धं बहिरङ्गलक्षणमन्तरङ्गलक्षणे' इत्युच्यते अक्षद्यूः हिरण्यद्यूः असिद्धत्वाद्बहिरङ्गलक्षणस्योठोन्तरङ्गलक्षणो यणादेशो न प्राप्नोति ॥

(उद्योतः) भाष्ये—**बहिरङ्गलक्षणस्येति** । ऊठ इति शेषः ।

(समाधानभाष्यम्)

नैष दोषः । 'असिद्धं बहिरङ्गलक्षणमन्तरङ्गलक्षणे' इत्युक्त्वा ततो वक्ष्यामि "नाजानन्तर्ये बहिष्ट्वप्रक्लृप्तिः" इति ॥

(प्रदीपः) **नाजानन्तर्ये इति** । अचोरानन्तर्यमाश्रित्य यत्र कार्यं विधीयते तत्रैषा परिभाषा नोपतिष्ठते ॥

(उद्योतः) अत्रैकदेशी समाधत्ते—**नाजानन्तर्ये इति** ॥ **अचोरिति** । द्वित्वमविवक्षितं, तेन वक्ष्यमाणेन षत्वतुग्ग्रहणरूपेण ज्ञापकेन न विरोधः । अचोन्यानन्तर्यनिमित्तकेन्तरङ्गे कर्तव्ये कृते च तस्मिन् प्राप्तेऽन्तरङ्गे कर्तव्ये जातस्य बहिरङ्गस्यासिद्धत्वं नेति तदर्थः ॥ एतेन पचावेदमित्यादौ गुणेऽजानन्तर्याश्रयणादसिद्धत्वानापत्तिरित्यपास्तम् ॥ अयजे इन्द्रं धियतीत्यादि च सिद्धम् । अक्षद्यूरित्यत्र यणि लोपाभावश्च सिद्धः ॥

(आक्षेपभाष्यम्)

सा तर्ह्येषा परिभाषा कर्तव्या ।

(सिद्धान्तिभाष्यम्)

न कर्तव्या । आचार्यप्रवृत्तिर्ज्ञापयति भवत्येषा परिभाषेति यदयं "षत्वतुकोरसिद्धः" इत्याह ॥

(प्रदीपः) **यदयमिति** । कोसिचदधीत्येति बहिरङ्गस्यैकादेशस्यासिद्धत्वात्षत्वं न भविष्यति तुक्च प्रवर्तिष्यते इति किमसिद्धवचनेन ॥

(उद्योतः) **तुक् तु प्रवर्तिष्यत इति** । समासोत्तरं ल्यप्प्रवृत्त्या पूर्वं पूर्वपदसंबन्धेन समासे जाते तत्र संहितायां नित्यत्वादेकादेशे ल्यपि तुगपेक्षया पदद्वयसंबन्धिवर्णापेक्षैकादेशस्य दध्यत्रेत्यादौ संयोगान्तलोपापेक्षया यणो बहिरङ्गत्वेनासिद्धत्ववदसिद्धत्वेन तत्प्रवृत्तिरिति भावः । षत्वग्रहणं तु न युक्तं ज्ञापकं, त्रैपादिकेन्तरङ्ग एतत्परिभाषायाः कार्यकालपक्षेप्यप्रवृत्तेर्**विसर्जनीयसू**त्रभाष्यसंमतत्वात् ॥षत्वस्यापि पदद्वयसंबन्धिवर्णद्वयापेक्षत्वेनान्तरङ्गत्वाभावाच्च ॥ न चाधीत्येत्यादौ **पूर्वं धातुरुपसर्गेण युज्यते** इत्येकादेशोऽन्तरङ्ग इति वाच्यम् । साधनबाधकप्रत्ययोत्पत्त्यनन्तरं पदान्तरसंबन्धनिमित्तकार्यात्पूर्वमुपसर्गसंबन्धेन तन्निमित्तकस्यान्तरङ्गत्वमिति तदर्थो न तु प्रत्ययनिमित्तादपीति तदर्थ इति **संप्रसारणाच्चे**ति सूत्रे भाष्ये स्पष्टत्वात् । तत्र हि खट्वा आ ऊढेत्यत्र सवर्णदीर्घाद् गुणोऽन्तरङ्ग इत्युक्तम् ॥ **सुट् कात्पूर्व** इत्यादिसूत्रेष्वप्युक्तम्—उपसर्गार्थेन पूर्वं संबन्धस्ततः प्रत्यये कृते उपसर्गेण संबन्ध इति संकृति इति स्थितेऽन्तरङ्गतरार्थकोपसर्गनिमित्तकः सुट् द्वित्वादितः पूर्वमिति । एवं च विशिष्टोपसर्गनिमित्तकत्वादुपसर्गार्थाश्रितमुपसर्गनिमित्तं कार्यमन्तरङ्गम्, यत्तु न तथा तत्र पूर्वागतसाधनकार्यमेवान्तरङ्गम् । अत एव प्रेद्ध इत्यत्र गुणो बहिरङ्ग इति भाष्ये उक्तम् । अस्याश्च परिभाषाया भाष्येऽन्यत्र काप्यव्यवहारादियमेकदेश्युक्तिः । एतज्ज्ञापकेनान्तरङ्गपरिभाषाया अनित्यत्वमेव ज्ञाप्यमिति तत्त्वम् ॥

(आक्षेपभाष्यम्)

इयं तर्हि परिभाषा कर्तव्या—"असिद्धं बहिरङ्गलक्षणमन्तरङ्गलक्षणे" इति ॥

(सिद्धान्तिभाष्यम्)

एषा च न कर्तव्या, आचार्यप्रवृत्तिर्ज्ञापयति

भवत्येषा परिभाषेति, यदयं "वाह ऊठ्" इति ऊठं शास्ति ॥

(प्रदीपः) यदयमिति। दित्यवाह् अस् इति स्थिते वाहः सम्प्रसारणमेव कर्तव्यम्। तत्र कृते पूर्वैकादेशे च ण्व्याश्रये गुणे वृद्धिरेचीति वृद्धौ सिद्धं दित्यौह इति॥ अनकारान्ते चोपपदे वहेश्छन्दसि ण्विर्न दृश्यते। प्रयोगदर्शने वा सत्यूहतेः क्विपि प्रयोगो भविष्यति किमूडादेशविधानेनेति परिभाषाया ज्ञापक ऊड्विधिः। तस्यां हि सत्यां बहिरङ्गस्य सम्प्रसारणस्यासिद्धत्वादन्तरङ्गो गुणो न स्यादित्यूड् विधीयते॥

(उद्द्योतः) वृद्धौ सिद्धमिति। परिभाषासत्त्वे तु विभक्तिनिमित्तसंप्रसारणस्य ण्व्याश्रयेऽन्तरङ्गे गुणेऽसिद्धत्वात्तदभावे वृद्धौ गुणस्यासिद्धत्वात्तदभावे च वृद्ध्यर्थमूडावश्यक इति भावः॥ नन्वनकारान्तेऽकारान्तोपसर्गे चोपपदेऽवर्णाभावात्पररूपेण बाधाच्च वृद्धिरेचीत्यस्याप्राप्तावूठ्संप्रसारणयोः फले विशेष इत्यत आह—अनकारान्तेति। इदमकारान्तोपसर्गोपलक्षणम्॥ छन्दसीति। न च ण्यन्तात् क्विपि वच्यादिभ्यो विहितत्वाभावेन सम्प्रसारणाभावे विश्ववाट्छन्दो लोकेप्यस्त्वेवेति वाच्यम्। क्वौ लुप्तमित्यस्य काचित्कतया णिलोपस्य स्थानिवत्त्वेन तत्र वाह ऊठ्सूत्रस्य प्राप्तेरेवाभावादित्याहुः। वस्तुतो लोकेपि वहेर्ण्विदर्शनाच्छन्दसीत्युपलक्षणम्। ऊहतेरिति। धातूनामनेकार्थत्वान्नार्थभेदः॥

(अन्तरङ्गपरिभाषादूषणकरणम्)

(१०३७ दूषणवार्तिकम्॥ २५॥)

॥ * तस्य दोषः पूर्वपदोत्तरपदयोर्वृद्धिस्वरावेकादेशात्॥ * ॥

(भाष्यम्) तस्यैतस्य लक्षणस्य दोषः पूर्वोत्तरपदयोर्वृद्धिस्वरावेकादेशादन्तरङ्गतोभिनिर्वृत्तात्र प्राप्नुतः। पूर्वैषुकामशमः अपरैषुकामशमः गुडोदकं तिलोदकम्। "उदके केवले" इति पूर्वोत्तरपदयोर्व्यपवर्गाभावान्न स्यात्॥

(प्रदीपः) पूर्वैषुकामशम इति। पूर्व इषुकामशमी अ इति स्थिते यद्यन्तरङ्गत्वादाद्गुणः स्यात्तदा पूर्वोत्तरपदयोर्व्यपवर्गाभावादुभयत आश्रयणेन्तादिवद्भावनिषेधाच्च दिशो मद्राणां 'प्राचां ग्रामनगराणा'मित्युत्तरपदवृद्धिर्न स्यात्। उत्तरपदवृद्धौ सर्वं चेति चशब्दाद्दिक्शब्दश्चेति तथैव पूर्वपदान्तोदात्तत्वं न स्यात्। सावकाशं चैतदुभयं पूर्वकार्ष्णमृत्तिक इति॥ गुडोदकमिति। उदके केवले इति पूर्वपदान्तोदात्तत्वं न स्यात्। उदश्वितुदकमित्यादावेव तु स्यात्॥

(उद्द्योतः) भाष्ये—तस्यैतस्येति। असिद्धं बहिरङ्गमित्यस्येत्यर्थः॥ दिशो मद्राणामिति। इत्यनुवर्तमाने इति शेषः॥ अत्रापि स्वर उदाहर्तुं शक्य इत्यभिप्रायेणाह—उत्तरपदेति॥ चशब्दाद्दिक्शब्दश्चेति॥ अनेन विहितं पूर्वपदान्तोदात्तत्वं तथैव व्यपवर्गाभावान्न स्यादित्यन्वयः॥ भाष्ये—उदके केवले इति। मिश्रवाचिनि समासे उदके परे पूर्वमन्तोदात्तमिति तदर्थः॥ एतदुदाहरणमेकदेशिनः। अन्तादिवच्चेतिसूत्रे पूर्वान्तवद्भावेनात्रैतत्स्वरसाधनात्। उभयाश्रयत्वं तु नात्र, एकदेशविकृतस्यानन्यत्वादकशब्दस्याप्युदकशब्देन ग्रहणादिति तत्र कैयटः॥

(दूषणपरिहारभाष्यम्)

नैष दोषः। आचार्यप्रवृत्तिर्ज्ञापयति-'पूर्वोत्तरपदयोस्तावत्कार्यं भवति, नैकादेशः' इति, यदयं "नेन्द्रस्य परस्य" इति प्रतिषेधं शास्ति॥ कथं कृत्वा ज्ञापकम्? । इन्द्रे द्वावचौ। तत्रैको "यस्येति च" इति लोपेनापह्रियते, अपर एकादेशेन, ततोऽनच्क इन्द्रः संपन्नः, तत्र कः प्रसङ्गो वृद्धेः। पश्यति त्वाचार्यः—'पूर्वपदोत्तरपदयोस्तावत्कार्यं भवति नैकादेशः' इति। ततो "नेन्द्रस्य परस्य" इति प्रतिषेधं शास्ति॥

(उद्द्योतः) भाष्ये—नेन्द्रस्येति। ननूभयत आश्रयणेन्तादिवत्त्वाभावेप्यन्तादिवत्त्वेपि व्यपवर्गाभावे वा सैमेन्द्र इति तदुदाहरणे विकारविशिष्टेन्तवद्भावेन पूर्वपदत्वे न्द्रशब्दे एकदेशविकृतन्यायेनेन्द्रशब्दत्वात्सामर्थ्येनान्त्यवृद्धिनिषेध एवास्त्वत आह—इन्द्रे द्वावचाविति॥ एको यस्येतीति। यद्यपि वृद्धिः परा तथापि लोपो नित्य इति भावः। न च परादिवद्भावेनैकादेशविशिष्टस्योत्तरपदत्वमेवास्त्विति तत्सम्भव इति वाच्यम्। एकदेशविकृतन्यायस्याप्याद्यायांशोपबोधकत्वेन व्यपवर्गस्य निरूपयितुमशक्यत्वात्। किं चेन्द्ररूपोत्तरपदाद्यच्स्थानिकवृद्धेस्तदभावेनाप्राप्तेस्तद्रूप्यानतिदेशादिति दिक्॥

(१०३८ दूषणवार्तिकम्॥ २६॥)

॥ * ॥ यणादेशादियुवौ॥ * ॥

(भाष्यम्) यणादेशादियुवौ अन्तरङ्गतोभिनिर्वृत्तान्न प्राप्नुतः। वैयाकरणः सौवश्व इति। लक्षणं हि भवति—'य्वोरचि वृद्धिप्रसङ्गे इयुवौ भवतः' इति॥

(प्रदीपः) प्रसङ्गेन व्याकरणान्तरे लक्षणं विचारयितुमाह—यणादेशादिति॥

(उद्द्योतः) पाणिनीये तादृशलक्षणाभावादाह—प्रसङ्गेनेति। तदेव दर्शयति—भाष्ये लक्षणं हि भवति य्वोरिति॥

(दूषणनिरासभाष्यम्)

नैष दोषः । अनवकाशावियुवौ । अचीत्युच्यते ॥

(उद्योतः) अनवकाशत्वे हेतुः—अचीत्युच्यत इति । यत इत्यादिः ॥

(आक्षेपभाष्यम्)

किं पुनः कारणमचीत्युच्यते ? ॥

(आक्षेपभञ्जनभाष्यम्)

इह मा भूताम्—ऐतिकायनः औपगव इति ॥

(आक्षेपरञ्जनभाष्यम्)

स्तामत्रेयुवौ, "लोपो व्योर्वलि" इति लोपो भविष्यति ॥

(प्रदीपः) लोपो भविष्यतीति । ननु बहिरङ्गत्वादियुवोरसिद्धत्वाल्लोपो न प्राप्नोति । अत्राहुः—समुदायस्यासिद्धत्वं नावयवस्येति ॥ समुदायस्यासिद्धत्वे सामर्थ्यात्तदवयवस्याप्यसिद्धत्वमिति चिन्त्यमेतत् ॥

(उद्योतः) बहिरङ्गत्वादिति । वृद्धिप्रसङ्ग इत्युक्तेस्तन्निमित्तनिमित्तकत्वादित्यर्थः ॥ चिन्त्यमिति । एवं च स्तामत्रेत्यादिग्रन्थः पूर्वपक्ष्येकदेशिसिद्धान्त्येकदेशिनोरुक्तिरिति भावः ॥ वस्तुतः परिभाषारम्भे दोषात्परिभाषा न कार्येति पूर्वपक्षिणो वाक्ये तामादाय दोषोद्भावनमयुक्तमिति चिन्त्यमेव चिन्त्यम् ॥

(आक्षेपभञ्जनभाष्यम्)

यत्र तर्हि लोपो नास्ति—प्रैयमेधः प्रैयङ्गव इति ॥

(१०३९ दूषणवार्तिकम् ॥ २७ ॥)

॥ * ॥ उसि पररूपाच्च ॥ * ॥

(भाष्यम्) उसि पररूपाच्चान्तरङ्गतोभिनिर्वृत्तादियादेशो न प्राप्नोति । पचेयुः यजेयुः ॥

(प्रदीपः) पचेयुरिति । पच् अ या उस् इति स्थिते यद्यत्रान्तरङ्गत्वात्पररूपं क्रियेत तदा व्यपवर्गाभावादियादेशो न स्यात् ॥ एकादेशस्यान्तवत्त्वाद्भविष्यतीति चेद्, एवमपि रूपं न सिध्येत् ॥

(उद्योतः) या उसिति स्थिते इति । अन्तरङ्गत्वादियः पूर्वं सलोपः ॥ व्यपवर्गाभावादिति । याशब्दाभावादिति भावः ॥ न सिध्येदिति ॥ उकारान्तस्येयापत्तेरिति भावः ॥

(दूषणभञ्जनभाष्यम्)

नैष दोषः । नैवं विज्ञायते—या इत्येतस्य इय् भवतीति ॥ कथं तर्हि ? । यासित्येतस्य इय् भवतीति ॥

(प्रदीपः) यासित्यस्येति । सलोपापवाद इयादेशः । अकृते सलोपे नास्ति पररूपप्रसङ्गः ॥

(उद्योतः) यासिति च्छेदे येय इति सौत्रो निर्देश इति भावः ॥ अतो या इय इत्येव पाठ इत्यानेमुक्सूत्रे भाष्ये ॥ ननु नित्यान्तरङ्गत्वेन सलोपे यासेव दुर्लभोऽत आह—सलोपापवाद इति । वार्णपरिभाषयेदं सिध्यति । तदनाश्रयणेन तु भाष्यम् ॥

(१०४० दूषणवार्तिकम् ॥ २८ ॥)

॥*॥ लुक्लोपयणयवायावेकादेशेभ्यः ॥ *॥

(भाष्यम्) लोपयणयवायावेकादेशेभ्यो लुक् बलीयानिति वक्तव्यम् ॥ लोपात्—गोमान् प्रियो यस्य गोमत्प्रियः । गोमानिवाचरति गोमत्यते यवमत्यते ॥ यणादेशात्—ग्रामण्यः कुलं ग्रामणिकुलम् । सेनान्यः कुलं सेनानिकुलम् ॥ अयवायावेकादेशेभ्यः—गवे हितं गोहितम् । रायः कुलं रैकुलम् । नावः कुलं नौकुलम् । वृकाद्भयं वृकभयम् । लुक् च प्राप्नोत्येते विधयश्च परत्वादेते विधयः स्युः । लुग्बलीयानिति वक्तव्यम् । लुक् यथा स्यात् ॥ विप्रतिषेधे परं कार्यम् ॥ २ ॥

इति श्रीमद्भगवत्पतञ्जलिविरचिते व्याकरण-महाभाष्ये प्रथमस्याध्यायस्य चतुर्थपादे प्रथममाह्निकम् ॥

(प्रदीपः) गोमत्प्रिय इति । यद्यत्र लोपः स्यात्तदा प्रत्ययलक्षणेन नुमादि स्यात् ॥ ग्रामणिकुलमिति । यणादिषु कृतेषु लुकि सति रूपं न सिध्येत् ॥ वृकादिति । पूर्वमेकादेशे कृते तस्यादिवद्भावाल्लुकि सति रूपं न सिध्येत् ॥ 'अन्तरङ्गानपि विधीन्बहिरङ्गो लुग्बाधते' इत्यस्य प्रत्ययोत्तरपदयोश्चेत्यत्र ज्ञापितत्वात्सिद्धम् ॥ २ ॥

इत्युपाध्यायजैयटपुत्रकैयटकृते महाभाष्यप्रदीपे प्रथमस्याध्यायस्य चतुर्थे पादे प्रथममाह्निकम् ॥

(उद्योतः) लुग्लोपयोः फले विशेषमाह—यद्यत्रेति । लुकि तु न लुमतेति निषेध इति भावः ॥ भाष्ये—परत्वादेत इति ॥ परत्वादुत्कृष्टत्वादन्तरङ्गत्वादित्यर्थस्तदाह—अन्तरङ्गानपीति ॥ २ ॥

इति शिवभट्टसुतसतीगर्भजनागोजी(नेश)भट्टकृते भाष्यप्रदीपोद्योते प्रथमाध्यायस्य चतुर्थे पादे प्रथममाह्निकम् ॥

प्रथमाध्यायस्य चतुर्थपादे द्वितीयमाह्निकम्

(विधिशेषप्रकरणे नदीसंज्ञाप्रकरणम्)

(१६६ नदीसंज्ञासूत्रम् ॥ १ । ४ । २ आ. १ सू.)

२४२ यू स्त्र्याख्यौ नदी ॥१ । ४ ।३ ॥

(यूपदनिर्णयाधिकरणम्)

(अनुयोगभाष्यम्)

यू इति किमर्थम् ? ।

(प्रदीपः) यूस्त्र्याख्यौ नदी ॥ ३ ॥ यू इति किमर्थमिति । स्त्र्याख्यं नदीत्येतावदेवास्तु ज्ञापकादापो न भविष्यतीति प्रश्नः ।

(उद्द्योतः) यू स्त्र्याख्यौ ॥ ३ ॥ ननु यूपदाभावे स्त्र्याख्यमात्रेऽतिप्रसङ्गः स्त्र्याख्याविति द्विवचनवैयर्थ्यं चेत्यत आह— स्त्र्याख्यं नदीत्यादि ॥

(समाधानभाष्यम्)

खट्वा । माला ॥ किंच स्यात् ? । खट्वाबन्धुः मालाबन्धुः "नदी बन्धुनि" इत्येष स्वरः प्रसज्येत ॥ इह च बहुखट्वक इति "नद्यृतश्च" इति नित्यः कप्प्रसज्येत ॥

(प्रदीपः) एष स्वर इति । पूर्वपदप्रकृतिस्वरं बाधित्वा पूर्वपदान्तोदात्तत्वमित्यर्थः । इष्यते च पूर्वपदप्रकृतिस्वरेणाद्युदात्तत्वम् । खट्वाशब्दस्य नित्स्वरेणाद्युदात्तत्वात् ।

(उद्द्योतः) ननु खट्वाशब्दस्य फिषोन्तोदात्तत्वेन पूर्वपदप्रकृतिस्वरतत्स्वरयोर्न विशेषोऽत आह—नित्स्वरेणेति । खटेः क्वनि खट्वाशब्दनिष्पत्तेरिति भावः ॥

(समाधानबाधकभाष्यम्)

नैष दोषः । आचार्यप्रवृत्तिर्ज्ञापयति—नापो नदीसंज्ञा भवतीति यदयं "ङेराम्नद्याम्नीभ्यः" इति पृथगाब्ग्रहणं करोति ॥

(समाधानान्तरभाष्यम्)

इह तर्हि-मात्रे मातुरिति "आण्नद्याः" इत्याट् प्रसज्येत ॥

(प्रदीपः) मातुरिति । मातृशब्दः सम्बन्धिवचनः स्त्रीविषय एवेति नाख्याग्रहणेन निवर्त्यते । परिच्छेत्तृवाची त्वन्य एव मातृशब्दः । नद्यृतश्चेति ऋग्रहणमस्यर्थं स्याद् बहुपितृक इत्यज्ञापकमृकारान्तानां नदीसंज्ञाभावस्य ॥

(उद्द्योतः) ननु मातृशब्दस्य जननीपरिच्छेत्तृवाचकतया नानालिङ्गत्वेन स्त्र्याख्यत्वाभावोऽत आह—मातृशब्द इति । आख्याग्रहणसामर्थ्याच्च लिङ्गव्यतिरिक्तार्थभेदः शब्दभेदनियामक इति न दोष इति भावः ॥ बहुपितृक इत्यनन्तरमितिरध्याहार्यः ॥

(इवर्णोवर्णयोर्दीर्घत्वनिर्णयाधिकरणम्)

(अनुयोगभाष्यम्)

किं पुनरिदं दीर्घयोर्ग्रहणमाहोस्विद्ध्रस्वयोः ? ।

(प्रदीपः) किं पुनरिति । ननु समानधर्मानुपपत्त्या सन्देहाभावात्प्रश्नानुपपत्तिः । नहि दीर्घनिर्देशे यू इति निर्देशोपपत्तिः । एवं तर्हि युक्तायुक्तत्वनिरूपणाय प्रश्नः ॥

(उद्द्योतः) समानधर्मानुपपत्तिमेव दर्शयति—नहीति ॥ एवं तर्हीति । निर्देशानुपपत्त्या ह्रस्वपक्षस्यैव युक्तत्वमिति व्युत्पादनाय प्रश्न इति भावः ॥

(प्रत्यनुयोगभाष्यम्)

किं चातः ? ।

(दीर्घग्रहणे दूषणभाष्यम्)

यदि दीर्घयोर्ग्रहणं यू इति निर्देशो नोपपद्यते । दीर्घाद्धि पूर्वसवर्णदीर्घः प्रतिषिध्यते ॥ उत्तरत्र च संज्ञिविशेषणं न प्रकल्पेत—यू ह्रस्वाविति । यदि यू, न ह्रस्वौ । अथ ह्रस्वौ, न यू । यू ह्रस्वौ चेति विप्रतिषिद्धम् ॥

(प्रदीपः) उत्तरत्र चेति । ह्रस्वनिर्देशे तु ह्रस्व इत्येकत्वस्याविवक्षितत्वाद्यू ह्रस्वाविति विशेषणविशेष्यभावोपपत्तिः । असति तु विशेषणे मात्रे मातुरित्यत्रापि प्रसङ्गः ॥

(उद्द्योतः) भाष्ये—निर्देशो नोपपद्यत इति । छान्दसत्वकल्पनं वृथेति भावः ॥ दीर्घमात्रग्रहणार्थं तत्स्यादिति न वृथात्वमत आह—उत्तरत्र चेति । ननु ह्रस्वनिर्देशेऽपि यू ह्रस्व इति भिन्नार्थकवचनत्वात्सामानाधिकरण्यानुपपत्तिरत आह—ह्रस्व इतीति । वेदाः प्रमाणमित्यादावप्येवमेव ॥ नन्वेकत्वाविवक्षापेक्षया यू इत्यस्यासंबन्ध एव कल्प्य इत्यत आह—असतीति ॥

(ह्रस्वग्रहणे दूषणभाष्यम्)

अथ ह्रस्वयोः 'हे शकटे' अत्रापि प्रसज्येत ॥

(प्रदीपः) अथ ह्रस्वयोरिति । दीर्घयोरप्यण्सवर्णान् गृह्णातीति सिध्यति ॥ ननु चोकाल इत्यत्रोक्तम्—अणुदित्सवर्णस्येत्यत्राशब्दसंज्ञाग्रहणमनुवर्तते । ततश्च सवर्णग्रहणेन न भाव्यम् ॥ नैष दोषः । नेयङुवङ्स्थानावस्त्रीति प्रतिषेधात्सवर्णग्रहणं भविष्यतीति । नहि ह्रस्व इयङुवङ्स्थानः

व्याख्योऽस्ति । अस्त्रीत्ययमपि निषेधपर्युदासः सवर्णग्रहणस्य ज्ञापकः ॥

(उद्द्योतः) ननु ह्रस्वनिर्देशे दीर्घयोर्न स्यादिति कुतो नोक्तमत आह—**दीर्घयोरपीति ॥ अनुवर्तते इति** । तच्च सप्तम्या विपरिणमय्य शब्दसंज्ञायां विधेयायां सवर्णग्रहणं नेत्यर्थकरणादिति भावः ॥ भाष्ये—**हे शकटे इति** । पर्जन्यवल्लक्षणप्रवृत्त्याऽम्बार्थनद्योरिति ह्रस्वे कृते हे गौरि इतिवद्गुणो न स्यादिति भावः ॥

(दूषणबाधकभाष्यम्)

नैष दोषः । अवश्यमत्र विभाषा नदीसंज्ञैषितव्या । उभयं हीष्यते—हे शकटि, हे शकटे इति च ॥

(प्रदीपः) **अवश्यमत्रेति** । तत्र दीर्घग्रहणपक्षे शकटिशब्दस्याप्राप्ता पक्षे नदीसंज्ञा विधेया । ह्रस्वपक्षे तु नित्यप्राप्ता पक्षे बाध्येति नास्ति विशेषः । अथ तु बह्वादिषु शकटिशब्दो विभाषा ङीषर्थः पठ्यते तदा दीर्घनिर्देशपक्षे पाक्षिके ङीषि हे शकटि इति भवति, शकटिशब्दस्य हे शकटे इति । ह्रस्वनिर्देशे तु ङीषि सत्यसत्यपि हे शकटीति प्राप्नोतीत्यस्ति भेदः ॥

(उद्द्योतः) **नास्ति विशेष इति** । वचनारम्भं प्रतीति शेषः ॥ **अथ त्विति** । असंदिग्धे संदिग्धवचनमेतत् ॥ **पठ्यते इति** । पाठाभावेऽपि सर्वतोऽक्तिन्नर्थादिति ङीषि शकटीशब्दस्य सत्त्वमिति बोध्यम् ॥ **अस्ति भेद इति** । एवं चोभाभ्यामप्यवश्यं वचनं कार्यमित्याशयकभाष्यमेकदेश्युक्तिरिति भावः ॥

(दूषणान्तरभाष्यम्)

इह तर्हि शकटिबन्धुरिति "नदी बन्धुनि" इत्येष स्वरः प्रसज्येत । इह च बहुशकटिरिति "नद्यृतश्च" इति कप्प्रसज्येत ॥

(प्रदीपः) **एष स्वर इति** । पूर्वपदान्तोदात्तत्वम् । पूर्वपदप्रकृतिस्वरेण तु शकटिशब्दे त्रयोऽप्यचः पर्यायेण उदात्ता भवन्ति शकटिशकट्योरक्षरमक्षरं पर्यायेणेति वचनात् ॥ **इह चेति** । शेषाद्विभाषेति विभाषा कब्भविष्यते, नित्यश्च प्राप्नोति ॥

(नियमेनदूषणपरिहारभाष्यम्)

नैष दोषः । "ङिति ह्रस्वश्च" इत्ययं नियमार्थो भविष्यति—ङित्येव यू ह्रस्वौ नदीसंज्ञौ भवतः, नान्यत्रेति ॥

(नियमत्वबाधकाक्षेपभाष्यम्)

कैमर्थक्यान्नियमो भवति ? ॥

(प्रदीपः) **कैमर्थक्यादिति** । कोऽर्थोऽस्येति किमर्थकम् । तस्य भावः कैमर्थक्यम् । प्रश्नविषयविषयिणोः सम्बन्धो भावप्रत्ययेनोच्यते । यत्र तत्साध्यस्यार्थस्य सिद्धत्वात्किमर्थमिति प्रश्नस्तस्यैव नियमार्थत्वं न तु प्रयोजने सतीत्यर्थः ॥

(उद्द्योतः) ननु किंशब्दोऽनिर्धारितविशेषविषये प्रश्ने, प्रश्नविषयत्वं च नियमार्थत्वे प्रयोजकमत आह—**कोऽर्थ इति** । **अर्थः** प्रयोजनम् । **संबन्धो** विषयविषयिभावः । समासकृत्तद्धितोत्तरत्वादेः संबन्धार्थकत्वादित्यर्थः ॥ प्रश्नविषयत्वे बीजं दर्शयन् तस्य नियमप्रयोजकत्वमाह—**यत्रेत्यादि** ॥

(नियमत्वसाधकसमाधानभाष्यम्)

विधेयं नास्तीति कृत्वा ॥

(उद्द्योतः) एवं च विधेयत्वाभिमतान्यथासिद्धिर्नियमप्रयोजिकेति फलितम् तदाह—भाष्ये—**विधेयं नास्तीत्यादि** । अस्त्री वा नदीसंज्ञो नेति केवलस्त्रीशब्दादौ प्राप्त्या तदन्ते चाद्यापि नित्यस्त्रीलिङ्गावित्यर्थाज्ञानात्प्राप्तिं मत्वैवं व्याख्यातम् ॥

(नियमत्वबाधनबाधकभाष्यम्)

इह चास्ति विधेयम् ॥ किम् ?। नित्या नदी संज्ञा प्राप्ता, सा विभाषा विधेया । तत्रापूर्वो विधिरस्तु नियमो वास्त्विति । अपूर्व एव विधिर्भविष्यति न नियमः ॥

(नियमत्ववादिनः प्रश्नभाष्यम्)

अथायं नित्यो योगः स्यात् प्रकल्पेत नियमः ? ॥

(विधित्ववादिनः समाधानभाष्यम्)

बाढं प्रकल्पेत ।

(नियमत्वसंपादकनित्यत्वसाधकभाष्यम्)

नित्यस्तर्हि भविष्यति । तत्कथम् ?। योगविभागः करिष्यते—इदमस्ति "यू स्त्र्याख्यौ नदी" "नेयङुवङ्स्थानावस्त्री" "वामि" । ततो "ङिति" ङिति चेयङुवङ्स्थानौ यू वा अस्त्री नदीसंज्ञौ न भवतः । ततो "ह्रस्वौ" ह्रस्वौ च यू स्त्र्याख्यौ ङिति नदीसंज्ञौ भवतः । इयङुवङ्स्थानौ वा नेति निवृत्तम् ॥

(अनुपपत्तिभाष्यम्)

यद्येवं शकटये । अत्र गुणो न प्राप्नोति ॥

(प्रदीपः) **यद्येवं शकटय इति** । नित्यया नदीसंज्ञया घिसंज्ञाया बाधितत्वात् ॥

(उद्द्योतः) ननु शेषग्रहणप्रत्याख्यानाद् घित्वेन गुणो भविष्यतीत्यत आह—**नित्ययेति** । विभक्तेन ह्रस्वावित्यनेन नित्यसंज्ञाया एव विधानादिति भावः ।

(अनुपपत्तिपरिहारभाष्यम्)

द्वितीयो योगविभागः करिष्यते । शेषग्रहणं न करिष्यते ॥ कथम् ? । इदमस्ति—"यू स्त्र्याख्यौ नदी" "नेयङुवङ्स्थानावस्त्री" "वामि" । ततो

"ङिति" ङिति चेयङुवङ्स्थानौ यू वा अस्त्री नदीसंज्ञौ न भवतः। ततः "ह्रस्वौ" ह्रस्वौ च यू स्त्र्याख्यौ ङिति नदीसंज्ञौ भवतः । इयङुवङ्स्थानौ वा नेति निवृत्तम् । ततो "घि" घिसंज्ञौ भवतः स्त्र्याख्यौ यू ह्रस्वौ ङिति । ततः—"असखि" । सखिवर्जितौ च यू ह्रस्वौ घिसंज्ञौ भवतः॥ स्त्र्याख्यौ ङितीति च निवृत्तम् ॥

(प्रदीपः) ततो घीति । एकविषयत्वाच्च घिनदीसंज्ञयोरेकसंज्ञाधिकाराच्च पर्यायेण प्रवृत्तौ शकट्यै शकटये इति च सिध्यति ॥

(उद्योतः) भाष्ये—शेषग्रहणं न करिष्यत इति । तत्सत्त्वे हि स्त्रीलिङ्गह्रस्वयोर्नदीसंज्ञाया उक्तत्वेनानुक्तनदीत्वाभावात् तत्र घिसंज्ञा विधातुमशक्येति भावः ॥ ननु घित्वेपि नदीत्वानिवृत्तेराडाद्यपि स्यादत आह—एकविषयत्वादिति । एकसंज्ञाधिकाराच्चेति पर्याये हेतू ॥

(योगविभागवैयर्थ्यभाष्यम्)

यदि तर्हि शेषग्रहणं न क्रियते नार्थ एकेनापि योगविभागेन । अविशेषेण नदीसंज्ञोत्सर्गः। तस्याः ह्रस्वयोर्घिसंज्ञा बाधिका । तस्यां नित्यं प्राप्तायामियं ङिति विभाषाऽऽरभ्यते ॥

(प्रदीपः) अविशेषेणेति । ह्रस्वयोर्दीर्घयोश्चेत्यर्थः । बाध्यत्वादुत्सर्गसामान्यादुत्सर्ग इत्युक्तम् । परत्वात्तु पुम्पुंसकयोः कृतार्था घिसंज्ञा नदीसंज्ञाया बाधिका ॥ तस्यामिति । अङिति तु शकटिबन्धुर्बहुशकटिरित्यादौ घिसंज्ञया नदीसंज्ञाया बाधितत्वाद्दोषाभावः ॥

(उद्योतः) अविशेषेणेत्यस्य स्त्रीपुंसाविशेषेणेति नार्थ इत्याह—ह्रस्वयोरिति ॥ ननु स्त्रियां नदीत्वं घित्वं लिङ्गत्रयसाधारणमिति सावकाशत्वात्कथमुत्सर्गापवादभावोऽत आह—बाध्यत्वादिति ॥ सामान्यम् । बाध्यत्वलक्षणसादृश्यम् ॥

(दीर्घग्रहणपक्षाभ्युपगमभाष्यम्)

अथवा पुनरस्तु दीर्घयोः ॥

(आक्षेपस्मारणभाष्यम्)

ननु चोक्तम्—निर्देशो नोपपद्यते। दीर्घाद्धि पूर्वसवर्णदीर्घः प्रतिषिध्यत इति ॥

(समाधानभाष्यम्)

"वा छन्दसि" इत्येवं भविष्यति ॥

(समाधानबाधकभाष्यम्)

छन्दसीत्युच्यते । न चेदं छन्दः ॥

(समाधानसाधकभाष्यम्)

छन्दोवत्सूत्राणि भवन्तीति ॥

(प्रदीपः) छन्दोवदिति । तादर्थ्यात्सूत्रेष्वपि छन्दःशब्दो वर्तत इति च्छन्दोविषयं कार्यं सूत्रेष्वपि प्रवर्तते । गौणमुख्यन्यायश्छन्दःप्रदेशेषु निर्देशान्यथानुपपत्त्या नाश्रीयते ॥

(उद्योतः) सूत्रेष्वपीति। छन्दोवदित्यतिदेशादिति भावः॥ तादर्थ्यादिति । छन्दोवदतिदेशे बीजमुक्तम् ॥ निर्देशान्यथानुपपत्त्येति । निर्देशकल्पितातिदेशान्यथानुपपत्त्येत्यर्थः । अतिदेशविषये तदैयर्थ्यापत्त्या गौणमुख्यन्यायाप्रवृत्तेरिति भावः ॥

(दूषणान्तरनिराकरणभाष्यम्)

यदप्युच्यते—'उत्तरत्र विशेषणं न प्रकल्पेत—यू ह्रस्वाविति । यदि यू न ह्रस्वौ । अथ ह्रस्वौ, न यू । यू ह्रस्वाविति च विप्रतिषिद्धम्' इति ॥ नैतद्विप्रतिषिद्धम् । आद्यायं यू ह्रस्वाविति । यदि यू न ह्रस्वौ, अथ ह्रस्वौ न यू ॥ त एवं विज्ञास्यामः—य्वोर्यौ ह्रस्वाविति ॥ कौ च य्वोर्ह्रस्वौ ? । सवर्णौ ॥

(स्त्र्याख्यशब्दसाधनाधिकरणम्)

(अनुयोगभाष्यम्)

अथ स्त्र्याख्याविति कोयं शब्दः? ।

(प्रदीपः) अथेति । यथाऽर्थोभिप्रेतस्तथा न शब्दसंस्कारोस्तीति प्रश्नः ॥

(उद्योतः) शब्दे संदेहाभावात् कोयमिति प्रश्नोऽनुपपन्न इत्यत आह—यथार्थ इति ॥

(समाधानभाष्यम्)

स्त्रियमाचक्षाते स्त्र्याख्यौ ॥

(उद्योतः) भाष्ये एकदेश्याह—स्त्रियमिति ।

(समाधानबाधकभाष्यम्)

यद्येवं स्त्र्याख्यायाविति प्राप्नोति । अनुपसर्गे हि को विधीयते ॥

(प्रदीपः) अनुपसर्गे हीति । यस्त्वातश्चोपसर्ग इति कः स परत्वात्कर्मण्यणित्यणा बाध्यते ।

(उद्योतः) इतर आह—यद्येवमिति ॥ स्त्र्याख्यायाविति । कर्मण्यण्यातोयुका भाव्यमिति भावः ॥ यस्त्विति । यद्यप्याचष्टे इत्याख्य इति व्युत्पाद्य पश्चात्षष्ठीसमासे सिध्यति, तथापि स्त्रियमाचक्षाते इति विग्रहोल्लेखादेवमुक्तम् ॥

(एकदेशिसमाधानसाधकभाष्यम्)

न तर्हीदानीमिदं भवति—

"यस्मिन्दश सहस्राणि पुत्रे जाते गवां ददौ ।
ब्राह्मणेभ्यः प्रियाख्येभ्यः सोयमुञ्छेन जीवति॥"

छन्दोवत्कवयः कुर्वन्ति ॥

(प्रदीपः) न तर्हीति । शिष्टप्रयोगादस्मिन्विषये कप्र-

त्ययस्य साधुत्वमेष्टव्यमिति भावः ॥ छन्दोवत्कवय इति । तेनच्छान्दसत्वाद्भविष्यति ॥

(उद्द्योतः) पुनरेकदेश्याह—न तर्हीदानीमिति । सौत्रप्रयोगे विप्रतिपन्नं प्रति श्लोकानुपपत्तिकथनमसङ्गतमत आह—शिष्टेति ॥ स एवाह—छन्दोवदिति । इदमेष्टव्यमिति भावः ।

(समाधानबाधकभाष्यम्)

नह्येषा इष्टिः ॥

(प्रदीपः) नह्येषेति । असाधव एवैवमादयः । न तु तत्प्रामाण्यात्साधुत्वव्यवस्था ॥

(उद्द्योतः) इतर आह—नह्येषेति ॥ तद्व्याचष्टे—असाधव इति । ऋषीणां तपोमाहात्म्यात्तु तदुच्चारयितॄणामस्माकं न प्रत्यवाय इति बोध्यम् ।

(समाधानान्तरभाष्यम्)

एवं तर्हि कर्मसाधनो भविष्यति । स्त्रियामाख्यायेते स्त्र्याख्यौ ॥

(प्रदीपः) आख्यायेते इति । घञर्थे कविधानमिति कप्रत्ययः । साधनं कृतेति सप्तमीसमासः ।

(उद्द्योतः) स्त्रियामाख्यायेते इति भाष्ये शास्त्रेणेति शेषः । ननूपपदत्वाभावात्समासो न स्यादत आह—साधनमिति ॥

(समाधानबाधकभाष्यम्)

यदि कर्मसाधनः कृत्स्त्रिया धातुस्त्रियाश्च न सिद्ध्यति तन्त्र्यै लक्ष्म्यै श्रियै भ्रुवै ।

(प्रदीपः) कृत्स्त्रिया इति । नहि तयोरीकारोकारौ स्त्रियां विहितौ यथा ङ्यूङाविति भावः ॥

(उद्द्योतः) नहीति । ईकाराद्यन्तस्य स्त्रियां विधानाभावाद्वर्णयोः संज्ञेति वाच्यम् । एवं च ङ्यूङोरेव स्यान्न तु तन्त्र्यादेरिति भावः ।

(समाधानान्तरभाष्यम्)

एवं तर्हि बहुव्रीहिर्भविष्यति—स्त्रियमाख्या अनयोः स्त्र्याख्यौ ॥

(प्रदीपः) एवं तर्हीति । आख्यानमाख्या । आतश्चोपसर्गे इत्यङ् । स्त्रियामाख्यानमनयोरिति बहुव्रीहिः । अत्र पक्षे सूत्रेणैव प्रत्ययः समासश्च सिद्ध्यतीति भावः ॥ स्त्रियां स्त्रीविषये आख्या प्रतिपादनमित्यर्थः ॥

(उद्द्योतः) प्रतिपादनं, शास्त्रेणेत्यर्थः ॥

(समाधानबाधकभाष्यम्)

एवमपि कृत्स्त्रिया धातुस्त्रियाश्च न सिध्यति तन्त्र्यै लक्ष्म्यै श्रियै भ्रुवै ॥

(प्रदीपः) एवमपीति । नहि तयोः स्त्रियां विधानमित्यर्थः ॥

(समाधानान्तरभाष्यम्)

एवं तर्हि विच् भविष्यति ॥

(प्रदीपः) एवं तर्हीति । असरूपत्वादणा पक्षे विज् न बाध्यते । समुदायधर्मस्यावयव आरोपात् कृत्स्त्रिया अप्यत्र पक्षे संज्ञा सिद्ध्यति ॥

(उद्द्योतः) भाष्ये एवं तर्हि विजिति । सूत्राणां छन्दोवत्त्वादिति भावः ॥ किंतु नोक्तस्तस्यादन्तेभ्योऽनभिधानात् । अत एव शंस्था इत्यादौ नेत्त्वम् । एवं चादन्तधातुप्रकृतिकमादन्तं प्रातिपदिकं लोकेऽसाध्विति बोध्यम् । आदन्तेभ्यो विचश्छन्दसि विधानादित्याहुः ॥ वर्णयोः स्त्र्याख्यानकर्तृत्वाभावात्कथं तन्त्र्यादौ सिद्धिरत आह—समुदायेति । ङ्यूङोस्तु शास्त्रकल्पितं तदस्तीति भावः ॥ अत्र पक्षे तदन्तसंज्ञापक्षो वक्तुं शक्य इति चिन्त्यम् । अत्र पक्षे आच्छीनद्योरित्यादिविषयेऽवयवे समुदायरूपारोपेण निर्वाह इति बोध्यम् ॥

(कप्रत्ययाभ्युपगमभाष्यम्)

अथ वा पुनरस्तु क एव—स्त्रियमाचक्षाते स्त्र्याख्याविति ॥

(आक्षेपस्मारणभाष्यम्)

ननु चोक्तम् 'स्त्र्याख्यायाविति प्राप्नोति अनुपसर्गे हि को विधीयते' इति ॥

(समाधानभाष्यम्)

मूलविभुजादिपाठात्को भविष्यति । एवं च कृत्वा सोप्यदोषो भवति यदुक्तम्—

"यस्मिन्दश सहस्राणि पुत्रे जाते गवां ददौ ॥
ब्राह्मणेभ्यः प्रियाख्येभ्यः सोयमुञ्छेन जीवति"॥

इति ॥

(आख्याग्रहणप्रयोजनाधिकरणम्)

(अनुयोगभाष्यम्)

अथाख्याग्रहणं किमर्थम् ?।

(प्रदीपः) आख्याग्रहणमिति । विच्पक्षे आख्याशब्द एवायम् । कप्रत्ययपक्षे तु प्रवृत्तिनिमित्तनिर्देशः ॥ यू स्त्रियामित्येव स्त्र्यर्थवृत्तित्वं लभ्यत इति प्रश्नः ॥

(उद्द्योतः) कप्रत्ययपक्षे आख्यशब्दसत्त्वेनाख्याग्रहणमित्ययुक्तमत आह—विजिति ॥ प्रवृत्तिनिमित्तेति । एवं चाख्याबोधकं ग्रहणमित्यर्थ इति भावः ॥

(१०४१ समाधानवार्तिकम् ॥ १ ॥)

॥ * ॥ नदीसंज्ञायामाख्याग्रहणं स्त्रीविषयार्थम् ॥ * ॥

(भाष्यम्) नदीसंज्ञायामाख्याग्रहणं क्रियते स्त्रीविषयार्थम् । स्त्रीविषयावेव यौ नित्यं तयोरेव नदीसंज्ञा यथा स्यात् । इह मा भूत्—ग्रामण्ये सेनान्ये स्त्रियै इति ।

(प्रदीपः) **स्त्रीविषयार्थमिति** । आख्याग्रहणसामर्थ्यान्नियम आश्रीयते ॥ स्त्रियमेव यावाचक्षाते न तु लिङ्गान्तरयुक्तमपीत्यर्थः ॥ **ग्रामण्ये इति** । ग्रामणीशब्दः क्रियाशब्दत्वात् त्रिलिङ्गत्वात् स्त्रीविषयो न भवतीति स्त्रियामपि वर्तमानो नदीसंज्ञो न भवति ॥ यद्येवमिष्वशनिप्रभृतीनामुभयलिङ्गानां पट्वादीनां च गुणवचनत्वात्सर्वलिङ्गानां स्त्रीविषयत्वाभावात् स्त्रियां वृत्तौ **ङिति ह्रस्वश्चेति** नदीसंज्ञा न प्राप्नोति ॥ एवं तर्हि **ङिति ह्रस्वश्चे**त्यत्रैवंविधो नियमो नाश्रीयते । केवलस्य स्त्रीशब्दस्यानुवर्तनादित्यदोषः ॥

(उद्द्योतः) **नियम इति** । वार्त्तिके विषयशब्दोऽनन्यभावे तद्द्योतक एवकारो भाष्ये । एवकारार्थ एव च नित्यग्रहणेनान्वाख्यायत इति बोध्यम् ॥ **स्त्रियमेवेति** । स्त्रीत्वविशिष्टमेवेत्यर्थः ॥ **क्रियाशब्दत्वादिति** । प्रवृत्तिनिमित्तभेद एव शब्दभेदप्रयोजको न तु विशेष्यभेदो नापि लिङ्गभेदस्तद्भेदेपि भेदव्यवहाराभावादिति भावः ॥ **ङिति ह्रस्वश्चेत्यत्रेति** । ह्रस्वघटितवाक्ये दीर्घघटितवाक्ये च । एतदुपसंहारे स्फुटीभविष्यति ॥

(उपसर्जने नदीसंज्ञासाधनाधिकरणम्)

(१०४२ आक्षेपवार्तिकम् ॥ २ ॥)

॥ * ॥ प्रथमलिङ्गग्रहणं च ॥ * ॥

(भाष्यम्) प्रथमलिङ्गग्रहणं च कर्तव्यम् । प्रथमलिङ्गे यौ स्त्र्याख्यौ इति वक्तव्यम् ।

(प्रदीपः) **प्रथमलिङ्गग्रहणमिति** । यः शब्दः प्रथमं स्त्रीत्वविशिष्टार्थमाह पश्चात्तु प्रकारान्तरेणार्थान्तरं लिङ्गान्तरयुक्तं तस्य तदानीमस्त्र्याख्यत्वादप्राप्ता नदीसंज्ञानेन विधीयते ॥

(उद्द्योतः) भाष्ये **प्रथमलिङ्गेति** । वृत्तेः पूर्वं लिङ्गबोधके वृत्तिघटकशब्दे विद्यमानौ स्त्र्याख्यौ यू तयोर्वृत्तौ स्त्र्याख्यत्वाभावेपि नदीत्वार्थमित्यर्थः ॥ तदन्तसंज्ञापक्षे वृत्तिघटकशब्दे विद्यमानत्वं तस्य व्यपदेशिवद्भावेन बोध्यं तदाह—**यः शब्द इति** । यद्यप्यर्थभेदाच्छब्दभेदस्तथापि श्रुत्यैक्यमात्रेणाभेदाध्यवसायात्तच्छब्दबोधितैक्योपपत्तिः ॥ प्रकारान्तरं, वृत्त्यन्तरप्राप्तिः ॥

(अनुयोगभाष्यम्)

किं प्रयोजनम् ? ।

(१०४३ समाधानवार्तिकम् ॥ ३ ॥)

॥ * ॥ प्रयोजनं क्विब्लुप्समासाः ॥ * ॥

(भाष्यम्) क्विप्—कुमार्यै ब्राह्मणाय ॥ लुप्—खरकुट्यै ब्राह्मणाय ॥ समास—अतितन्त्र्यै ब्राह्मणाय । अतिलक्ष्म्यै ब्राह्मणाय ॥

(प्रदीपः) **क्विबिति** । कुमारीमिच्छत्यात्मनः कुमारीयति । ततः कर्तरि क्विप् । अथ वा कुमारीवाचरतीत्याचारे क्विपं विधाय कर्तरि क्विब्विधेयः ॥ **खरकुट्यै इति** । खरकुटीवेतीवार्थे **संज्ञायामिति** कनो **लुम्मनुष्ये** इति लुप् । यद्यप्यत्र युक्तवद्भावात् स्त्रीत्वमस्ति तथापि स्वाश्रयस्य पुंस्त्वस्यानिवर्तनान्नायं स्त्रियामेव वर्तते । किं तर्हि? पुंस्यपीत्याख्याग्रहणान्नियमार्थादप्राप्ता नदीसंज्ञा विधीयते ॥ **अतितन्त्र्यै इति**। तन्त्रीमतिक्रान्त इति तत्पुरुषः ॥

(उद्द्योतः) आचारे **क्विपमिति** । प्रातिपदिकग्रहणे लिङ्गविशिष्टग्रहणादिति भावः । ङ्यन्तादाचारक्विप्सत्त्वे इदम् ॥ **खरकुटी वेति** । खरकुटशब्दात्पिप्पल्यादेराकृतिगणत्वाद् ङीष् । कुटीशब्देन समासो वा ॥ **पुंस्त्वस्यानिवर्तनादिति** । न च तदनिवृत्तौ खरकुटीः पश्येत्यादौ नत्वापत्तिः, प्रकृतिवदित्यतिदेशेन प्रकृतिलिङ्गप्रयुक्तकार्यातिदेशेन तद्विरुद्धस्वाश्रयकार्याप्रवृत्तेः ॥ स्पष्टं चेदं **स्त्रियामि**तिसूत्रे भाष्ये ॥ यद्वा तेन स्वप्रयुक्तकार्याभावोप्यतिदिश्यते । स्पष्टं चेदं **तस्माच्छस** इति सूत्रे भाष्यकैयटयोः ॥ अत्रापि पक्षे प्रकृते स्वाश्रयलिङ्गनिवृत्तौ मानाभाव इत्याशयः । तत्प्रत्याख्यानेपि स्त्र्याख्याविलस्य स्त्रीत्वेनैव य आहेति नार्थः, किं तु स्त्रीत्वविशिष्टमेव य आहेत्यर्थः । न चायं तथा, स्त्रीत्वेन रूपेण वस्तुतः पुंस्त्वादिविशिष्टस्याभिधानात् । न च पदार्थमात्रे शास्त्रीयलिङ्गत्रयस्य सत्त्वेनासम्भवः, व्यक्तिवस्तुपदार्थादिपदबोध्यत्वकाले तत्तल्लिङ्गोपजनेपि स्त्रीपदादिबोध्यत्वदशायां तत्सत्त्वे मानाभावात् । प्रकृते तु ब्राह्मणायेत्यादिविशेष्यदर्शनेन तत्सत्त्वानुमानात् । तत्फलं तु श्रिये ब्राह्मणायेत्यत्र लुपि **ङिति ह्रस्वश्चे**ति विकल्पाभावः ॥ **प्रथमलिङ्गं चे**ति तु न तद्विषयमिति वक्ष्यते ॥ एतेन यथा दारादिशब्दैः शब्दशक्तिस्वाभाव्याच्छास्त्रीयपुंस्त्वविशिष्टस्यैव स्त्रीरूपार्थस्याभिधानं तथा लुबन्तैरपि शास्त्रीयस्त्रीत्वविशिष्टस्यैव पुमादेरभिधानम् । अत एव तदशिष्यमित्यनेन तत्प्रत्याख्यानं सङ्गच्छते । एवं चास्यापि नित्यस्त्रीत्वमस्त्येवेत्यपास्तम् ॥ अतिशयिता तन्त्रीरिति विग्रहे दोषाभावादाह—**तन्त्रीमतीति** ।

(आक्षेपभाष्यम्)

तत्तर्हि वक्तव्यम् ? ।

(समाधानभाष्यम्)

न वक्तव्यम् ।

(१०४४ समाधानसाधकवार्तिकम् ॥ ४ ॥)

॥ * ॥ अवयवस्त्रीविषयत्वात्सिद्धम् ॥ * ॥

(भाष्यम्) अवयवोऽत्र स्त्रीविषयः । तदाश्रया नदीसंज्ञा भविष्यति ॥

(प्रदीपः) **अवयवस्त्रीविषयत्वादिति** । अन्तरङ्गत्वात् पूर्वमेव स्त्र्याख्यत्वात्प्रवृत्ता नदीसंज्ञा पश्चादुपजायमाने लिङ्गान्तरयोगे बहिरङ्गे न निवर्तेत इति भावः ॥

(उद्द्योतः) **बहिरङ्गे इति**। अकृतव्यूहपरिभाषा तु नास्त्येवेति भावः॥ यथोद्देशे इदम्। अवयवशब्देनात्र वृत्तिप्रकृतिभूतशब्दमात्रग्रहणम्। अत एव क्यजाद्यन्ते न दोषः। समुदाये कार्यप्रवृत्तिस्तु नद्यन्तत्वाद्बोध्या॥ वस्तुतः—कार्यकालपक्षेपि समासे स्पष्टैव तदवयवस्य तत्प्राप्तिः। अत एव भाष्ये **तदाश्रया नदीसंज्ञा भविष्यतीत्युक्तम्**। कार्यवेलायामपि भविष्यतीत्यर्थस्तस्य। कैयटरीत्या तु तदाश्रया नदीसंज्ञास्तीति वदेत्। कुमारीत्यादावपि विशेषणतया नित्यस्त्रीलिङ्गरूपार्थबोधकत्वमस्त्येव। प्राधान्येन तन्मात्रबोधकत्वनिवेशे तु न मानमित्याशयः॥

(१०४५ आक्षेपवार्तिकम्॥ ५॥)

॥ * ॥ अवयवस्त्रीविषयत्वात्सिद्धमिति चेदियङुवङ्स्थानप्रतिषेधप्रसङ्गे यण्स्थानप्रतिषेधप्रसङ्गोऽवयवस्येयङुवङ्स्थानत्वात्॥ * ॥

(भाष्यम्) अवयवस्त्रीविषयत्वात्सिद्धमिति चेदियङुवङ्स्थानप्रतिषेधप्रसङ्गे यण्स्थानयोरपि य्वोः प्रतिषेधः प्रसज्येत। आध्यै ब्राह्मण्यै॥ किं कारणम्?। अवयवस्य इयङ्स्थानत्वात्। अवयवोऽत्र इयङ्स्थानः॥

(प्रदीपः) **आध्यै इति**। आध्यायतीति ध्यायतेः सम्प्रसारणं चेति क्विप् सम्प्रसारणं च। अत्रावयवो धीशब्द इयङ्स्थानः। समुदायस्य त्वेरनेकाच इति यणा बाधितत्वादियङ्स्थानत्वाभावः॥ नन्वाधीप्रधीशब्दौ क्रियाशब्दत्वात्त्रिलिङ्गत्वात् स्त्रीविषयौ न भवतः। यथैव ग्रामणीसेनानीशब्दाविति नदीसंज्ञया न भाव्यमिति पूर्वापरव्याघातदर्शनाच्चिन्त्यमेतत्॥

(उद्द्योतः) **चिन्त्यमेतदिति**। आध्यायतीत्यादिविग्रह इत्यभिमानः। वस्तुतस्तु ध्यानं धीः आ ईषत् प्रकृष्टा वा धीर्यस्या इति विग्रहः। एवं च गतिपूर्वत्वाद्यणपि सुलभः। अवयवस्येयङ्स्थानत्वमिति भाष्यं च रमणीयमेव। आध्यै इत्यादौ समुदायस्य नित्यस्त्रीत्वाभावान्नदीत्वाप्राप्तेरवयवस्य सा वाच्या सा च न प्राप्नोति तस्येयङ्स्थानत्वाद्। वार्तिकारम्भे तु न दोषस्तेन हि प्राक्तननित्यस्त्रीत्वं गृहीत्वेदानीं सा प्रवर्तते। न चेदानीमसावियङ्स्थान इति निषेधाप्रवृत्तिः, प्राक्तनेयङ्स्थानत्वं गृहीत्वा निषेधस्य तु न प्रवृत्तिर्मानाभावादिति भावः॥ न च **गतिकारकपूर्वस्येत्यत्र** प्रतिपदोक्तपरिभाषया नित्यसमासस्यैव ग्रहणमित्यत्र यण् दुर्लभः। अत एव **कुन्मेजन्तसूत्रे मा नः समस्य दूढ्य** इति मन्त्रव्याख्यावसरे दुर्धिय इति कैयटेन प्रयुक्तमिति वाच्यम्। मानाभावात्। कैयटप्रयोगे दुःस्थिता धीर्येषामिति विग्रहेण धीशब्दं प्रति गतित्वाभावान्न दोषः। अत्र चेदमपि भाष्यं मानम्॥

(१०४६ समाधानवार्तिकम्॥ ६॥)

॥ * ॥ सिद्धं त्वङ्गरूपग्रहणाद् यस्याङ्गस्येयुवौ तत्प्रतिषेधात्॥ * ॥

(भाष्यम्) सिद्धमेतत्। कथम्। अङ्गरूपं गृह्यते यस्याङ्गस्य इयुवौ भवतस्तस्येदं ग्रहणम्। न चैतस्याङ्गस्य इयुवौ भवतः।

(प्रदीपः) **सिद्धं त्विति**। अचि श्नुधात्वित्यनेन अङ्गस्येयङुवङ्विधानात् सामर्थ्याक्षिप्तमत्राङ्गम्। तेन यस्याङ्गस्येयङुवङौ निर्वर्त्येते तस्य नदीसंज्ञानिषेधः। आध्यै इत्यत्रावयवस्याङ्गत्वं नास्ति। अङ्गस्य तु **एरनेकाच** इति यण्विधानादियङुवङ्स्थानता नास्तीति निषेधाभावः। एतदर्थमेव स्थानग्रहणं कृतम्। इयङुवङोर्यदा स्थितिस्तदा प्रतिषेधो यथा स्याद् यदा त्वपवादेन बाधस्तदा मा भूत्।

(उद्द्योतः) **सामर्थ्याक्षिप्तमिति**। इयङुवङ्स्थानत्वस्याङ्ग एव सम्भवादिति भावः। एतद्वार्त्तिकभाष्यप्रामाण्यादियङुवङ्भ्यामुपस्थितस्याङ्गस्य शाब्देऽन्वय इति तात्पर्यम्। **अङ्गत्वं नास्तीति**। ननु त्वदुक्तविग्रहेऽन्तर्वर्तिविभक्त्या धीशब्दस्याप्यङ्गत्वमस्त्येवेति चेन्न। नदीसंज्ञाकार्यप्रयोजकश्रूयमाणविभक्तिनिरूपिताङ्गे यत्र क्वापीयङादेः स्थितिस्तत्र निषेधात्। अत एव हे श्रीरित्यादौ निषेधस्तदाह—**एतदर्थमेवेति**। यत्र नदीकार्याश्रयेऽङ्गे बाधकाबाधितेयङुवङोः स्थितिः कचित्प्रयोगे दृष्टा तस्य शब्दस्य सति सम्भवे तदवयवस्य च नदीत्वं नेत्यर्थ इति भावः। प्रध्यै इत्यत्र चावयवनित्यस्त्रीत्वमादाय नित्यैव संज्ञा। इयङ्स्थानत्वाभावाच्च न **ङिति ह्रस्वश्चेति** विकल्पः। न च प्रधीशब्दावयवस्य नदीत्वे **नद्यृतश्चेति** कबापत्तिः समासात्पूर्वावस्थायामुत्तरपदस्य नदीत्व एव कपः प्रवृत्तेः॥

(१०४७ नियमवार्तिकम्॥ ७॥)

॥ * ॥ ह्रस्वेयुवस्थानप्रवृत्तौ च स्त्रीवचने॥ * ॥

(भाष्यम्) ह्रस्वौ च इयुव्स्थानौ च प्रवृत्तौ च प्राक् च प्रवृत्तेः स्त्रीवचनावेव नदीसंज्ञौ भवत इति वक्तव्यम्॥ शकट्यै अतिशकट्यै ब्राह्मण्यै। क मा भूत्?। शकटये अतिशकटये ब्राह्मणाय॥ धेन्वै अतिधेन्वै ब्राह्मण्यै। क मा भूत्?। धेनवे अतिधेनवे ब्राह्मणाय॥ श्रियै अतिश्रियै ब्राह्मण्यै। क मा भूत्?। श्रिये अतिश्रिये ब्राह्मणाय॥ भ्रुवै अतिभ्रुवै ब्राह्मण्यै। क मा भूत्?। भ्रुवे अतिभ्रुवे ब्राह्मणाय॥

(प्रदीपः) ह्रस्वेति॥ अवयवस्त्रीविषयत्वात् सिद्धमित्यस्यायमपवादः। ह्रस्वेयुवङ्स्थानानां प्रवृत्तिरर्थान्तरसंक्रान्तिस्तस्यां सत्यां स्त्रीवचने एव संज्ञा भवति न लिङ्गान्तरवचने। चशब्दादप्रवृत्तौ चेति ज्ञेयम्। एतदेव प्राक्प्रवृत्तेरिति भाष्ये स्पष्टीकृतम्।

(उद्द्योतः) नन्वेवमतिश्रियै ब्राह्मणायातिशकट्यै ब्राह्मणायेत्यादावयवस्त्रीत्वमादाय विकल्पापत्तिरित्याशङ्क्य भाष्ये ह्रस्वेयुविस्थादि॥ ङित्यत्याक्षिप्ताङ्गस्यैव स्त्रियामिति विशेषणमित्यनेनान्वाख्यायत इति बोध्यम्। आख्यापदं त्वत्र न संबध्यतेऽतिश्रियाइत्यादावङ्गस्य तत्त्वाभावात् पाक्षिकेनदीत्वानापत्तेः। एवं च समुदायस्यानेन नदीत्वं क्रियते। तत्र प्रथमलिङ्गग्रहणं चेत्यस्य प्रत्याख्यानरीत्या प्राप्त्यभावान्नञ् निवर्त्य विधित्वेनैव व्याचष्टे—नदीसंज्ञौ भवत इति॥ वस्तुतो वार्त्तिकेनाप्यतिलक्ष्म्यै इत्यादावयवस्यैव सा क्रियते इति समुदायस्य नैव प्राप्तिः अतिश्रियै इत्यादावयवस्य तेन प्राप्ता नेयङिति निषिद्धा। तस्य तु नानेन संज्ञाविकल्पो, यतो ङिद्विहितस्तदादित्वाभावात्। ह्रस्वावित्यादेर्ह्रस्वेवर्णाद्यन्ते इयङादिस्थानेवर्णाद्यन्ते च शब्दरूपे इति वार्त्तिकेऽर्थस्तादृशौ शब्दाविति भाष्येऽर्थ इत्यलम्॥ ननु प्रथमलिङ्गग्रहणस्य यू स्त्र्याख्याविलत्रोपसंख्यातत्वेन ङिति ह्रस्वश्चेत्यत्राप्रसक्तेर्ह्रस्वेयुवेत्यादि व्यर्थमत आह—अवयवेति॥ न्यायस्तत्रापि समान इति भावः। प्रथमलिङ्गेत्यस्य ङिति ह्रस्वश्चेत्यत्रानुवृत्तिभ्रमवारणायेदमिति तु भाष्ये वक्ष्यति॥ अतः कैयटे प्रत्याख्यानवाक्यमारम्भवाक्यस्याप्युपलक्षणं बोध्यम्॥

(व्याख्यान्तरभाष्यम्)

अपर आह—

॥ * ॥ ह्रस्वेयुवस्थानप्रवृत्तौ स्त्रीवचने ॥ * ॥

(भाष्यम्) ह्रस्वौ च इयुवस्थानौ च प्रवृत्तावपि स्त्रीवचनावेव नदीसंज्ञौ भवत इति वक्तव्यम्॥ किं प्रयोजनम्?। शकट्यै अतिशकट्यै ब्राह्मण्यै। क मा भूत्?। शकटये अतिशकटये ब्राह्मणाय॥ धेन्वै अतिधेन्वै ब्राह्मण्यै। क मा भूत्?। धेनवे अतिधेनवे ब्राह्मणाय॥ श्रियै अतिश्रियै ब्राह्मण्यै। क मा भूत्? श्रियै अतिश्रियै ब्राह्मणाय॥ भ्रुवै अतिभ्रुवै ब्राह्मण्यै। क मा भूत्?। भ्रुवे अतिभ्रुवे ब्राह्मणाय॥

(प्रदीपः) अपर आहेति। चशब्दोऽत्र न पठ्यत इति पूर्वस्माद्विशेषः। नहि प्राक् प्रवृत्तेः किंचिदनिष्टमापद्यते यदर्थः समुच्चयः क्रियते। पठ्यमानोपि चशब्दः स्त्रीवचनशब्देन सम्बध्यते स च नियमार्थः॥ क्वचिद्भाष्ये पठ्यते—"अस्त्रीवचनावेव नदीसंज्ञौ भवत इति वक्तव्यम्। शकट्यै अतिशकट्यै ब्राह्मणाय। क मा भूत्?। शकटये अतिशकटये ब्राह्मण्यै" इत्यादि। एष त्वपपाठः। उपसंहारस्यान्यथाभिधानात्॥

(उद्द्योतः) नहि प्राक् प्रवृत्तेरिति। ननु नयतीति नीस्तमतिक्रान्तायै अतिनियै ब्राह्मण्यै हरिमतिक्रान्तायै अतिहर्यै इत्यत्र नदीत्वापत्तिरूपमनिष्टमस्त्येव। न. चाङ्गस्य नित्यस्त्रीत्वाभावात्र दोषस्तस्य नित्यस्त्रीत्वेन विशेषणेऽतिश्रियै ब्राह्मण्यै इत्यसिद्ध्यापत्तेरिति चेन्न। तादृशानामनभिधानात्॥ नियमार्थ इति। अस्त्रीवचनाङ्ग्याहृत्यर्थ इत्यर्थः। शकट्यै इत्युदाहरणं तु ब्रुवन्तं बोध्यम्॥ उपसंहारस्येति। प्रथमलिङ्गग्रहणं चोदितं तद्द्वेष्यमित्यादेरित्यर्थः॥

(अनुयोगभाष्यम्)

किमर्थं पुनरिदमुच्यते?॥

(समाधानभाष्यम्)

प्रथमलिङ्गग्रहणं चोदितं तद्द्वेष्यं विजानीयात्सर्वमेतद्विकल्पते इति तदाचार्यः सुहृद्भूत्वान्वाचष्टे ह्रस्वौ चेयुवस्थानौ च प्रवृत्तौ च प्राक् च प्रवृत्तेः स्त्रीवचनावेवेति॥ यू स्त्र्याख्यौ नदी॥ ३॥

(उद्द्योतः) द्वेष्यमित्यस्यानिष्टविषयकमपीत्यर्थः॥ विकल्पत इत्यत्रोपसर्गोऽविवक्षितार्थः॥ तदाचार्य इति। अस्माकमय उक्तः॥३॥

(इति नदीसंज्ञाप्रकरणम्)

———

(अथ घिसंज्ञाप्रकरणम्)

(१६७ घिसंज्ञाविकल्पसूत्रम्।१।४।२ आ. २ सू.)

२४९ षष्ठीयुक्तश्छन्दसि वा॥ ९॥

(१०४८ आक्षेपवार्तिकम्॥ १॥)

[॥ * ॥ योगविभागः॥ * ॥]

(भाष्यम्) योगविभागः कर्तव्यः॥ "षष्ठीयुक्तश्छन्दसि" षष्ठीयुक्तः पतिशब्दश्छन्दसि घिसंज्ञो भवति। ततो "वा" वा छन्दसि सर्वे विधयो भवन्ति॥ सुपां व्यत्ययः। तिङां व्यत्ययः। वर्णव्यत्ययः। लिङ्गव्यत्ययः। कालव्यत्ययः। पुरुषव्यत्ययः। आत्मनेपदव्यत्ययः। परस्मैपदव्यत्ययः॥ सुपां व्यत्ययः—'युक्ता मातासीद्धुरि दक्षिणायाः' दक्षिणायामिति प्राप्ते॥ तिङां व्यत्ययः—'चषालं ये अश्वयूपाय तक्षति' तक्षन्तीति प्राप्ते॥ वर्णव्यत्ययः—'त्रिष्टुभौजः शुभितमुग्रवीरम्' सुहितमिति प्राप्ते॥ लिङ्गव्यत्ययः—'मधोर्गृह्णाति' 'मधोस्तृप्ता इवासते' मधुन इति प्राप्ते॥ कालव्यत्ययः—'श्वो-

ऽग्नीनाधास्यमानेन' 'श्वः सोमेन यक्ष्यमाणेन'। श्व आधाता श्वो यष्टेति प्राप्ते ॥ पुरुषव्यत्ययः—'अधा स वीरैर्दशभिर्वियूयाः' वियूयादिति प्राप्ते ॥ आत्मनेपदव्यत्ययः—'ब्रह्मचारिणमिच्छते' इच्छतीति प्राप्ते ॥ परस्मैपदव्यत्ययः—'प्रतीपमन्य ऊर्मिर्युध्यति' 'अन्वीपमन्य ऊर्मिर्युध्यति' युध्यत इति प्राप्ते ॥ षष्ठीयुक्तः ॥ ९ ॥

(प्रदीपः) षष्ठीयुक्तः ॥ ९ ॥ योगविभाग इति । तेन परिभाषा सम्पद्यते । यावदिह शास्त्रे कार्यं तच्छन्दसि वा भवति । तत्रानेनैव सिद्धत्वाद्बहुलं छन्दसीत्यादि न वक्तव्यम् । एतदर्थश्च व्यत्ययो बहुलमित्यत्र योगविभागो न व्याख्येयः । उभयत्रविभाषा चेयं विज्ञेया ॥ सुपामिति । कर्मणि द्वितीयेत्यादेर्नियमस्य विकल्पनादनियमोपि च्छन्दसि भवतीति सुपां व्यत्ययसिद्धिः ॥ कालव्यत्यय इति । कालविहितप्रत्ययव्यत्यय इत्यर्थः ॥ ९ ॥

(उद्द्योतः) षष्ठीयुक्तः ॥ ९ ॥ अत्र षष्ठीपदं तदन्तपरम् । षष्ठ्या युक्त इत्यर्थे तु षष्ठ्यामित्येव सिद्धे युक्तग्रहणवैयर्थ्यापत्तेः। तत्र समासे पूर्वेणैव सिद्धत्वात्कुलुञ्चानां पतये नम इत्यसमासार्थमेवेदम् । न चैवमपि समासे छन्दसि परत्वादयमेव विकल्पः स्यादिति वाच्यम् । वेदे आपाद्यरूपाभावेनेष्टापत्तेः। तत्र बहुलं छन्दसीत्यादिबहुतराकरणलाघवाय योगविभागो भाष्ये कृतः ॥ नन्वेवमपि स्थलान्तरविहितानां कथं विकल्पसिद्धिरत आह—तेनेति । योगविभागसामर्थ्यगम्यसर्वविषयत्वेनेत्यर्थः ॥ परिभाषेति । कार्यमात्रं चास्या लिङ्गं तदाह—यावदिति ॥ उभयत्रविभाषेति । यत्रयत्रास्या उपस्थितिस्ते केचित्प्राप्तविभाषारूपाः केचिदप्राप्तविभाषारूपाः पर्यवस्यन्तीति भावः । यद्यपि तेषु विधिषु नित्यं प्राप्तेषु 'छन्दसि वा' इत्यनेन सर्वापि प्राप्तविभाषैव, तथाप्यस्य विकल्पविधेर्व्यत्ययमात्रपर्यवसन्नतयाऽस्त्येव तत्सम्भव इति बोध्यम् ॥ ननु स्वादिवाक्येनानियमेन प्राप्ते कथं व्यत्यय इत्यत आह—कर्मणीति । नियमस्यैव विकल्प इति भावः । यत्कर्मण्येवेति तच्छन्दसि वेति वचनव्यक्तेः। एवं च करणेऽप्राप्तद्वितीयाया यवाग्वाऽग्निहोत्रं जुहोतीत्यादौ प्रयोगभेदेन करणाकरणाभ्यां विकल्पेऽप्राप्तविभाषा । अन्यप्राप्तावन्यस्य करणाद् व्यत्ययत्वं च बोध्यम् ॥ सुहितमिति प्राप्ते इति । सकारहकारयोः शभौ ॥ क्वचित्तु क्षधितमिति प्राप्ते इति पाठो दृश्यते ॥ अधुन इति प्राप्ते इति । 'माध्वीर्गावो भवन्तु नः' इति क्षीरवाची नपुंसकलिङ्ग इति भावः ॥ कालव्यत्ययस्य ब्रह्मणोप्यशक्यत्वादाह—कालविहितेति ॥ ९ ॥

(इति घिसंज्ञाप्रकरणम्)

(१६८ अङ्गसंज्ञासूत्रम् ॥ १ । ४ । २ आ. ३ सू.)

२५३ यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् ॥ १३ ॥

(पदकृत्यकथनाधिकरणम्)

(आक्षेपभाष्यम्)

[अथ यस्माद्ग्रहणं किमर्थम्?॥]

(समाधानभाष्यम्)

यस्मादिति व्यपदेशाय ॥

(प्रदीपः) यस्मात्प्रत्ययविधिः ॥ १३ ॥ यस्मादिति व्यपदेशायेति । संज्ञिन इति शेषः । सति हि यस्मादित्यस्मिंस्तदादीत्यनेन संज्ञी निर्देष्टुं शक्यते नान्यथा । पराभ्रष्टव्यसंज्ञयनिर्देशे तदिति परामर्शाभावात्तदादीत्यसम्बद्धमेव स्यात् ॥

(उद्द्योतः) यस्मात् ॥ १३ ॥ ननु सर्वस्यापि शब्दस्य व्यवहाररूपव्यपदेशार्थत्वादत्रैव तत्कथनमनुचितमत आह—संज्ञिन इतीति ॥ ननु तदादिपदमेव संज्ञिनिर्देशकं भविष्यतीत्यत आह—सति हीति ॥ ननु यच्छब्दाभावे तच्छब्दप्रयोगो नेत्यसिद्धम् । 'ते तद्राजाः' 'कला च सा कान्तिमती कलावतः' 'सा गङ्गेत्यादौ प्रकृतप्रसिद्धानुभूतार्थकेषु व्यभिचारादित्यत आह—पराभ्रष्टव्येति । प्रकृतादेरभावादिति भावः ॥ तदिति परामर्शाभावादिति ॥ तदित्येतत्परामर्शयोग्याभावादित्यर्थः ॥ न च प्रत्ययविधौ इत्यत्र प्रकृतप्रत्ययस्यैव तदा परामर्शोऽस्तु यस्य प्रत्ययस्य विधिस्तदाद्यङ्गमित्यर्थोऽस्त्विति वाच्यम् । एवं हि विहितप्रत्ययादेरेवाङ्गसंज्ञा स्यादिति भविष्यतीत्यादौ धातोर्गुणानापत्तिः । एवं च विशिष्टसंज्ञिनिर्देशार्थं यस्मादित्युक्तमिति भावः । न च प्रकृत्यादि प्रत्ययेऽङ्गमित्येवास्तु, प्रकृत्यादीत्यस्य यस्मात्प्रत्ययविधिस्तदादीत्यस्य च पर्यायत्वेन पर्यायेषु लाघवगौरवविचारानादरात् । योगविभागेन वक्ष्यमाणपरिभाषालाभाय तथान्यासस्यावश्यकत्वाच्च ॥

(अनुयोगभाष्यम्)

अथ प्रत्ययग्रहणं किमर्थम् ॥

(समाधानभाष्यम्)

'यस्माद्विधिस्तदादि प्रत्ययेऽङ्गम्' इतीयत्युच्यमाने स्त्री इयती स्त्रीयतीत्यत्रापि प्रसज्येत । प्रत्ययग्रहणे पुनः क्रियमाणे न दोषो भवति ॥

(प्रदीपः) स्त्रीयतीति । स्त्रीशब्दात्तुशब्दस्य तल्लोपस्य च विधिरस्त्वीत्यभसंज्ञा स्याद्भसंज्ञा चेन्नि ज्ञाद्यनिमित्तो यस्येति चेतिलोपः प्रसज्येत । ईश इदमादेशस्य यस्येतिलोपस्याश्रित्वदत्राभादित्यसिद्धत्वं नास्ति । प्राग्भादसिद्धत्वमिति

केषांचिदभ्युपगमात् । पदान्तरनिरपेक्षपदसंस्कारपक्षे स्थानिवद्भावो नास्ति नानादिष्टादचः पूर्वः स्त्रीशब्द इति ॥

(उद्द्योतः) स्त्री इयतीति । इदंशब्दात्परिमाणे वतुः, वस्य घस्तस्य इयादेश इदम ईश् यस्येति लोपः । उगित्वान्ङीप् ॥ ननु यस्माद्विधिस्तदादि प्रत्ययेऽङ्गमित्युक्ते यत्र प्रत्ययेऽङ्गत्वं तस्यैव विधेः प्रत्यासत्त्या लाभेन प्रकृते न दोषोऽत आह—स्त्रीशब्दादिति । तदभावे तु व्याप्तिन्यायेनेहापि स्यात् । सति तु प्रत्ययग्रहणे तत्सामर्थ्यात्प्रत्यासत्तिरेवाश्रीयत इति भावः ॥ असिद्धत्वं नास्तीति । चिणो लुग्न्यायेन प्राप्तिः ॥ प्राग्भादिति । वस्तुतस्त्वियङाप-त्तिर्दोषः । न च तत्रापीलोपस्यासिद्धत्वं व्याश्रयत्वात्तत्प्राप्तेरभावात् । यस्येतिलोपप्राप्तिनिमित्तसमुदायापेक्षयाऽतिरिक्तस्य स्त्रीशब्दस्येयङपेक्षणादित्यादि षष्ठे निरूपयिष्यामः ॥ नानादिष्टादिति । इयङि न पदान्तेतिनिषेधोऽपि बोध्यः ॥

(अनुयोगभाष्यम्)

अथ विधिग्रहणं किमर्थम् ?।

(प्रदीपः) अथेति । यस्मात्प्रत्यय इत्यत्र विधीयत इत्यध्याहरिष्यत इति प्रश्नः ॥

(उद्द्योतः) ननु विधिग्रहणाभावे यस्मात्प्रत्यय इत्यस्य क्रियाकाङ्क्षा न शान्तेत्यत आह—अध्याहरिष्यत इति ॥

(समाधानभाष्यम्)

'यस्मात्प्रत्ययस्तदादि प्रत्ययेऽङ्गम्' इतीयत्युच्यमाने दधि अधुना, मधु अधुना, अत्रापि प्रसज्येत । विधिग्रहणे पुनः क्रियमाणे न दोषो भवति । तदेतत्प्रत्ययग्रहणेन विधिग्रहणेन च समुदितेन क्रियते संनियोगः—यस्माद्यः प्रत्ययो विधीयते तदादि तस्मिन्नङ्गसंज्ञं भवतीति ॥

(प्रदीपः) दधि अधुनेति । असति विधिग्रहणे परशब्दस्याप्यध्याहारः स्यात् । इदमो यदा अधुनाप्रत्ययो निपात्यते इदमादेशस्य चेशो यस्येति लोपस्तदेदं प्रत्युदाहरणम् ॥ यदा त्विदमोऽभावः धुना च प्रत्ययः । तदा स्त्रीयतीत्येतदेव प्रत्युदाहरणम् ॥ ननु क्रियमाणेपि विधिग्रहणेऽत्राङ्गसंज्ञा प्राप्नोति । अस्ति हि दधिशब्दात्सुप्रत्ययविधिरधुनाप्रत्ययश्च परः । ततश्चाङ्गसंज्ञायां भसंज्ञायां च सत्यां यस्येति लोपः प्राप्नोतीत्याह—तदेतदिति । प्रत्यासत्तिन्यायाश्रयणाद्यस्माद्यः प्रत्ययो विहितस्तस्मिन्नेव प्रत्यये परतस्तदाद्यङ्गमित्यर्थः ॥

(उद्द्योतः) परशब्दस्यापीति । यद्यपि यस्मादिति पञ्चम्या परशब्दाध्याहारस्योभयोरप्यावश्यकत्वं तथापि तावतैव विश्रान्तिः स्याद् न तु विधीयत इत्यस्यापि ॥ अपिरेवार्थे ॥ विधिग्रहणे इति । प्रत्ययग्रहणस्याप्युपलक्षणम् ॥ भसंज्ञायां चेति । न च सति प्रत्ययविधिग्रहणे यचि भमित्यत्रापि यस्माद्यजादिप्रत्ययविधि-रित्यर्थलाभात्तत्र भसंज्ञाप्राप्तिरिति वाच्यम् । यस्मात्प्रत्ययविधिस्तस्य यजादौ प्रत्यये भत्वमित्यर्थः स्यात् प्रत्यासत्तिन्यायानाश्रयणेनैवास्य ग्रन्थस्य प्रवृत्तेरिति भावः ॥ यस्येति लोप इति । इकोऽचीति नुमः प्राप्तिरित्यन्ये । प्राग्दिशीयत्वेनास्य विभक्तित्वाद् भत्वाच्च न नलोप इति तदाशयः ॥ इत्याहेति । इत्याशङ्कायामाहेत्यर्थः ॥ प्रत्यासत्तीति । तन्न्यायप्रवृत्तिलाभार्थमेवोभयमिति भावः । विधिग्रहणं भवन्तीत्यादावतो दीर्घ इति दीर्घव्यावृत्त्यर्थमित्यपि बोध्यम् । ध्वनितं चेदं श्नम्विधायके भाष्ये ॥

(अनुयोगभाष्यम्)

अथ तदादिग्रहणं किमर्थम् ? ॥

(उद्द्योतः) भाष्ये—अथ तदादीति । आदिग्रहणविषयः प्रश्नः ॥

(१०४९ समाधानवार्तिकम् ॥ १ ॥)

॥ * ॥ अङ्गसंज्ञायां तदादिग्रहणं स्यादिनुमर्थम् ॥ * ॥

(भाष्यम्) **अङ्गसंज्ञायां तदादिग्रहणं क्रियते स्याद्यर्थं नुमर्थं च ॥ स्याद्यर्थं तावत्—करिष्यावः करिष्यामः ॥ नुमर्थम्—कुण्डानि वनानि ॥**

(प्रदीपः) करिष्याव इति । विकरणान्तस्याङ्गसंज्ञायां सत्यां तन्निबन्धनमतो दीर्घो यञीति दीर्घत्वं भवति । अन्यथा पापाव इत्यादावेव स्यात् । पय्धातोर्यङ्लुगन्तस्य वलि लोपो व्योर्वलीति यलोपे दीर्घत्वे च रूपम् ॥ कुण्डानीति । यदा नुम्परादिस्तदात्र सुपि चेति दीर्घत्वं सिध्यति । दधीनीत्यादौ तु अनकारान्तत्वान्न सिध्यति । पूर्वान्तपक्षे सामानीत्यादिवत्सिध्यति । यदा त्वभक्तत्वपक्षस्तदेदं प्रयोजनमादिग्रहणस्य । पूर्वान्तपक्षस्तु स्थापित इत्यप्रयोजनमेतत् ॥

(उद्द्योतः) ननु दीर्घग्रहणविधानसामर्थ्यादनङ्गत्वेपि दीर्घोऽत आह—अन्यथेति । चिकीर्षामीत्यादौ शबकारदेशस्य पूर्वान्तवत्त्वेनाङ्गत्वात्तत्रापि दीर्घस्य चारितार्थ्यं बोध्यम् । करोवीत्यादौ गुणोपि प्रयोजनं बोध्यम् ॥ तदेदमिति । कुण्डानीत्येतदित्यर्थः ॥

(१०५० आक्षेपवार्तिकम् ॥ २ ॥)

॥ * ॥ मित्सुटोरुपसंख्यानम् ॥ * ॥

(भाष्यम्) **मित्वतः सुड्वतश्चोपसंख्यानं कर्तव्यम् ॥ मित्वतः—भिनत्ति छिनत्ति । अभिनत् । अच्छिनत् ॥ सुड्वतः—संचस्करतुः संचस्करुः ॥**

(प्रदीपः) मित्सुटोरिति । मित्सुटोः कृतयोरित्यर्थः । भाष्यकारस्तु वस्तुतोर्थं व्याचष्टे—मित्वत इति ॥ भिनत्तीति । रूपोदाहरणमेतत् । कार्योदाहरणं च अभिनदिति । नित्यत्वाद् श्नमि कृते अङ्गसंज्ञायामसत्यामडागमो न

स्यादित्यङ्गसंज्ञोपसंख्यायते ॥ **संचस्करतुरिति** । द्विर्वचने कृतेऽडभ्यासव्यवायेपीति सुटि चानङ्गत्वादृतश्च संयोगादेरिति गुणो न स्यात् । यदा तु **पूर्वं धातुरुपसर्गेण युज्यत** इत्येष पक्षस्तदान्तरङ्गत्वात्सुटि कृते तद्भक्तस्य तद्ग्रहणेन ग्रहणात्स्कृशब्दादेव प्रत्ययविधिरित्यङ्गसंज्ञा सिद्ध्यत्येव । स्कृशब्दस्य द्विर्वचने कृते **शर्पूर्वाः खय** इति खयः शेषे संचस्करतुरिति सिद्ध्यति । किं तु संस्कृषीष्ट संस्क्रियत इति इड्गुणनिवृत्तये कात्पूर्वग्रहणेनाभक्तत्वं सुटो ज्ञापितमिति पूर्वमपि प्रत्ययोत्पत्तेः सुटि कृते नास्ति सुट्सहितस्याङ्गसंज्ञेति गुणो न स्यादित्युपसंख्यानम् ॥

(उद्योतः) ननु मित्सुटोरङ्गत्वे न किंचित्प्रयोजनमत आह—**कृतयोरिति** । सति सप्तमीति भावः ॥ **भाष्येति** । सत्सप्तम्यैव सिद्धे मत्वध्याहाराश्रयणमयुक्तमतः फलितार्थकथनपरं भाष्यमित्यर्थः ॥ **रूपोदाहरणमिति** । मित्वद्रूपमीदृशमित्यर्थः ॥ अन्ये तु भिनत्तीत्यादावङ्गत्वाभावे लघूपधगुणाशङ्का कर्मधारयेण समाधानं च वृद्धोक्तमसंगतं स्यादिति भाष्याशयमाहुः ॥ ननु परत्वात्पूर्वमेवाडागमोऽत आह—**नित्यत्वादिति** । **लावस्थायामडिति** पक्षे भिन्धीत्यादावाङ्गं धित्वं न स्यादिति बोध्यम् ॥ ननु संशब्दमात्रापेक्षत्वेनान्तरङ्गत्वात्सुटि ततो लिडादिकमिति न दोषोऽत आह—**द्विर्वचन इति** । **पूर्वं धातुः साधनेन युज्यत** इति सिद्धान्तादिति भावः ॥ ननु टित्त्वाद्धात्ववयवत्वेन न दोषोऽत आह—**अडभ्यासेति** । नायं टित्त्वादाद्यवयवः किं त्वनेन मध्यं प्रवेशित इत्यभक्त इति भावः ॥ **तद्भक्तस्येति** । टित्त्वादित्यर्थः ॥ **स्कृशब्दादेवेति** । इदं चिन्त्यम् । एवं ह्यत्र धातूपसर्गयोः समासो दुर्वारः । स हि **पूर्वं धातुः साधनेनेति** न्यायेनोपपदमितिसूत्रे भगवता वारितः ॥ **इड्गुणेति** । ऋतश्च **संयोगादेर्गुणोर्त्तिसंयोगाद्योरिति** विहितेत्यर्थः ॥ **अभक्तत्वं सुटो ज्ञापितमिति** । इदं ज्ञापकं कथमिति चिन्त्यम् ॥ यद्वास्य इति गत्वेति शेषः । अत एवेड्गुणनिवृत्तये वचनमेव करिष्यति भाष्यकृत् षष्ठे । किं च सुटोऽभक्तत्वे सकारादेर्धातुत्वाभावात् स्कृशब्दस्य कथं द्वित्वमिति सुधीभिर्विभाव्यम् । यद्यप्यत्रत्यपूर्वपक्षिणः सुटोऽनवयवत्वाभिमानात्संचस्करतुरित्यादौ संयोगादित्वाभावादपि गुणो न प्राप्नोति तथापि **संयोगोपधग्रहणं कर्तव्यमिति** वार्तिकेन साध्यः । यद्यप्यवयवावयविभावस्य षष्ठ्यर्थस्याभावात्कथं तेनापि सिद्धिस्तथापि यदन्त्यवर्णनिरूपितमुपधात्वं संयोगस्येति निरूपकत्वलक्षणे षष्ठ्यर्थे बहुव्रीहिरित्यभिमानः ॥

(आक्षेपबाधकभाष्यम्)

किं पुनः कारणं न सिध्यति सुटो बहिरङ्गत्वात् । बहिरङ्गः सुट् अन्तरङ्गो गुणः । असिद्धं बहिरङ्गमन्तरङ्गे ॥

(उद्योतः) भाष्ये—किं पुनरिति प्रश्नमुपपादयति—**सुटो बहिरङ्गत्वादिति** ॥ बहिर्भूतोपसर्गनिमित्तत्वात्सुटो बहिरङ्गत्वम् । एवं च तस्यासिद्धत्वात्सिध्यत्येवाङ्गत्वमिति भावः ॥

(आक्षेपबाधकभाष्यम्)

वक्ष्यत्येतत् *संयोगादेर्गुणविधाने संयोगोपधग्रहणं कृञर्थम्* ॥

(उद्योतः) नन्वसिद्धत्वेनाङ्गत्वसाधने तेनैव संयोगादित्वाभावात्कथं गुणः स्यादत आह—**वक्ष्यत्येतदिति** । तथा च तत्सामर्थ्यात्तदंशे नासिद्धत्वमिति भावः ॥

(संयोगादिग्रहणवैयर्थ्यभाष्यम्)

यदि संयोगोपधग्रहणं क्रियते नार्थः संयोगादिग्रहणेन । इहापि सस्वरतुः सस्वरुरिति संयोगोपधस्येत्येव सिद्धम् ॥

(वैयर्थ्यनिरासभाष्यम्)

भवेदेवमर्थेन नार्थः । इदं तु न सिध्यति संचस्करतुः संचस्करुरिति ॥

(उद्योतः) सस्वरतुरित्यस्य संयोगोपधग्रहणेन सिद्धावपि तदा सामर्थ्याभावादसिद्धत्वाभावानुपपत्तौ संचस्करतुरित्यादि न सिध्यतीत्याह—**भवेदित्यादि संचस्करुरित्यन्तम्** । तस्मात्संयोगोपधग्रहणसामर्थ्योपपत्तये संयोगादिग्रहणमपि कार्यमिति भावः ॥

(अनुयोगभाष्यम्)

किं पुनः कारणं न सिध्यति ? ॥

(उद्योतः) तत्र संयोगोपधग्रहणे कृते यदि तत्सामर्थ्यादसिद्धत्वाभावस्तर्ह्यङ्गत्वेपि तद्विषये तदभावः स्यादिति तत्करणेपि तदसिद्धिरित्यत्रार्थोप्यभिप्रेतस्तत्र सिद्धत्वाभावे कुतोऽङ्गत्वं न सिध्यतीति पुनः पृच्छति—**किं पुनरिति** । एवं **सुटो बहिरङ्गत्वादि**त्यादि भाष्यं योजयन्ति केचित् ॥

परे तु भाष्ये **सुटो बहिरङ्गत्वादि**त्यादिः **किं पुनः कारणं न सिध्यती**त्यन्तो ग्रन्थ उपसर्गार्थसंबन्धो धातोः पूर्वमेव ततश्च प्रत्यये कृते द्विर्वचनात्पूर्वमन्तरङ्गतरार्थकोपसर्गनिमित्तकः सुट् इति लिटः स्कृशब्दाद्विध्यभावेन संयोगादेरङ्गत्वाभावाद्गुणो न प्राप्नोतीति भाष्याशय इति प्रामाणिकाः ॥

(अनुयोगसमाधानभाष्यम्)

इह तस्य वा ग्रहणं तदादेर्वा । न चेदं तद्, नापि तदादि ॥

(प्रदीपः) **तस्य वेति** । व्यपदेशिवद्भावादिति भावः ॥

(उद्योतः) ननु तदादिग्रहणे सति कथं तस्य केवलस्य ग्रहणमत आह—**व्यपदेशिवदिति** ।

(१०५१ समाधानवार्तिकम् ॥ ३ ॥)

॥ * ॥ सिद्धं तु तदाद्यादिवचनात् ॥ * ॥

(भाष्यम्) **सिद्धमेतत् ॥ कथम्? । तदाद्याद्यङ्गसंज्ञं भवतीति वक्तव्यम् ॥ किमिदं तदाद्यादीति ?** ।

तस्यादिस्तदादिस्तदादिरादिर्यस्य तदिदं तदाद्यादीति ॥

(प्रदीपः) तस्यादिरिति। भिद आदिर्भकारः स आदिर्भिनदित्यस्येति भवत्यङ्गसंज्ञा। एवं करोतेर्द्विर्वचने कृते चस्कृशब्दे स्थिते यस्मात्कृशब्दात्प्रत्ययविधिस्तस्यादिश्चकारः स एवादिश्चस्कृशब्दस्य ॥

(उद्द्योतः) तस्यादिश्चकार इति। द्विर्वचने द्विःप्रयोगत्वस्वीकारादित्यर्थः ॥

(आक्षेपभाष्यम्)

स तर्हि तथा निर्देशः कर्तव्यः? ॥

(समाधानभाष्यम्)

न कर्तव्यः। उत्तरपदलोपोऽत्र द्रष्टव्यः। तद्यथा— उष्ट्रमुखमिव मुखमस्य उष्ट्रमुखः, खरमुखः ॥ एवं तदाद्यादि तदादीति ॥

(प्रदीपः) उष्ट्रमुख इति। यथा गतार्थत्वान्मुखशब्दनिवृत्तिस्तथा पूर्वं प्रतिपादितम्। इहापि प्रतिलक्ष्यं लक्षणभेदात्तदवयवे तच्छब्दो वर्तत इति तदवयवादित्वान्मित्सुटोः कृतयोरङ्गसंज्ञा सिध्यति ॥

(उद्द्योतः) ननूष्ट्रमुखे बाधात्तथाङ्गीकारेऽपि करिष्याम इत्यादौ मुख्यार्थत्वेऽपि चारितार्थ्यादत्र लक्षणायां मानाभावोऽत आह— इहापीति ॥ प्रतिलक्ष्यमिति। तस्य लक्ष्यत्वनिश्चयः शिष्टप्रयोगादिति भावः ॥ तदवयवे इति। तदाद्यवयवे इत्यर्थः ॥

(१०५२ समाधानान्तरवार्तिकम् ॥ ४ ॥)

॥ * ॥ तदेकदेशविज्ञानाद्वा सिद्धम् ॥ * ॥

(भाष्यम्) तदेकदेशविज्ञानाद्वा सिद्धमेतत्। तदेकदेशभूतं तद्ग्रहणेन गृह्यते। तद्यथा गङ्गा यमुना देवदत्तेति। अनेका नदी गङ्गां यमुनां प्रविष्टा गङ्गायमुनाग्रहणेन गृह्यते। तथा—देवदत्तास्थो गर्भो देवदत्ताग्रहणेन गृह्यते ॥

(समाधानबाधकभाष्यम्)

विषम उपन्यासः। इह केचिच्छब्दा अव्यक्तपरिमाणानामर्थानां वाचका भवन्ति—य एते संख्याशब्दाः परिमाणशब्दाश्च। पञ्च सप्तेति। त एकेनाप्यपाये न भवन्ति। द्रोणः खारी आढकमिति नैवाधिके भवन्ति न च न्यूने। केचिद्यावदेव तद्भवति तावदेवाहुः—यथैते जातिशब्दा गुणशब्दाश्च। तैलं घृतमिति खार्यामपि भवति द्रोणेऽपि। शुक्लो नीलः कृष्ण इति हिमवत्यपि भवति वटकणिकामात्रेऽपि द्रव्ये। अङ्गसंज्ञा चाप्यव्यक्तपरिमाणानां क्रियते, सा केनाधिकस्य स्यात् ॥

(प्रदीपः) एकेनाप्यपाये इति। अपाये तस्य रूपस्यापगमे। एकेन करणेन। एकाभावेनेत्यर्थः। यथा वर्षकृतं दुर्भिक्षमिति वर्षमभवत् करणं संपद्यते ॥ अङ्गसंज्ञा चापीति। यस्मात्प्रत्ययविधिस्तदादीति विशिष्टरूपपरिग्रहात् ॥

(उद्द्योतः) भाष्ये—अव्यक्तपरिमाणानाम्। नियतपरिमाणानाम् ॥ एकेनाप्यपाये इति तृतीया न कर्तरि षष्ठ्या बाधादत आह—अपाये इति। न चैकस्य विद्यमानस्यापाये करणता संभवतीति सामर्थ्यात्तत्त्वाभावेनेति ज्ञायते। एवं चैकाभावेन पञ्चादिशब्दवाच्यरूपापाये पञ्चादिशब्दा न प्रवर्त्तन्त इति भावः। तत्र दृष्टान्तमाह—यथेति ॥ विशिष्टरूपपरिग्रहादिति। एवमुपसर्गादिसंज्ञा अप्यव्यक्तपरिमाणनिष्ठत्वान्न न्यूने लौकिकैकदेशविकृतन्यायेनेत्यपि बोध्यम् ॥

(समाधानसाधकभाष्यम्)

एवं तर्ह्याचार्यप्रवृत्तिर्ज्ञापयति—'तदेकदेशभूतं तद्ग्रहणेन गृह्यते' इति यदयं "नेदमदसोरकोः" इति सककारयोः प्रतिषेधं शास्ति ॥ कथं कृत्वा ज्ञापकम्?। इदमदसोः कार्यमुच्यमानं कः प्रसङ्गो यत्सककारयोः स्यात्। पश्यति त्वाचार्यः—'तदेकदेशभूतं तद्ग्रहणेन गृह्यते' इति, ततः सककारयोः प्रतिषेधं शास्ति ॥

(प्रदीपः) तदेकदेशभूतमिति। तन्मध्यपतितत्वात्तदेकदेशत्वावसायः ॥

(उद्द्योतः) नन्वभक्तत्वात्तदेकदेशत्वमेवासिद्धमत आह—तन्मध्येति ॥

(अनुयोगभाष्यम्)

अथ द्वितीयं प्रत्ययग्रहणं किमर्थम्?।

(१०५३ समाधानवार्तिकम् ॥ ५ ॥)

॥*॥ प्रत्ययग्रहणं पदादावप्रसङ्गार्थम् ॥*॥

(भाष्यम्) प्रत्ययग्रहणं क्रियते। पदादावङ्गसंज्ञा मा भूदिति। किं च स्यात्?। 'स्त्र्यर्थं श्र्यर्थं भ्वर्थम्' अङ्गस्येयङुवङौ स्याताम् ॥

(प्रदीपः) स्त्र्यर्थमिति। असति द्वितीये प्रत्ययग्रहणे प्रत्ययविधानमात्रप्रतिबद्धाङ्गसंज्ञा स्त्रीशब्दस्य प्राप्नोति। ततश्चतुर्थीविधानात्। ततश्चाङ्गाश्रय इयङ् स्यात्। पुनः प्रत्ययग्रहणे तु यस्मायः प्रत्ययो विहितः स एव यदि परो भवति तदा तस्याङ्गसंज्ञा भवति। यश्चात्र प्रत्ययो विहितो नासौ परः लुप्तत्वात्। न च प्रत्ययलक्षणं भवति, न लुमताङ्गस्येति निषेधात्। इयङादेशकार्यस्याङ्गत्वात्तस्मिन्कर्तव्ये निषेधप्रवर्तनात् ॥

(उद्द्योतः) भाष्ये—पदादाविति। पदादौ परे इत्यर्थः ॥ असतीति। तदभावे प्रत्यासत्तिन्यायोत्थानाभावादित्यर्थः ॥ निषे-

श्चादिति । अङ्गसंज्ञापि प्रत्यये परतः पूर्वस्य कार्यमिति भावः ॥ तस्मिन्कर्तव्ये इति । तन्निमित्तेऽङ्गत्वे कर्तव्ये इत्यर्थः ॥

(१०५४ समाधानवार्तिकम् ॥ ६ ॥)

॥ * ॥ परिमाणार्थं च ॥ * ॥

(भाष्यम्) परिमाणार्थं च द्वितीयं प्रत्ययग्रहणं क्रियते । 'यस्मात्प्रत्ययविधिस्तदाद्यङ्गम्' इतीयत्युच्यमाने दाशतयस्याप्यङ्गसंज्ञा प्रसज्येत ॥

(प्रदीपः) परिमाणार्थं चेति । अन्यथा देवदत्त ओदनमपाक्षीदिति देवदत्तशब्दात्सुप्रत्ययविधिरिति तदादेः संघातस्याङ्गसंज्ञायां सत्यां देवदत्तशब्दात्पूर्वोऽडागमः स्यात् । प्रत्ययग्रहणे तु सति यस्मात्यः प्रत्ययो विहितस्तस्मिन्नेव परतस्तदाद्यङ्गमिति विज्ञायमाने न भवत्यतिप्रसङ्गदोषः ॥ दाशतयस्येति । दशावयवा येषां ते दशतये । तेषु भवो दाशतयः । एतच्चानियमप्रतिपादनार्थं न त्वत्र दशसंख्या विवक्षिता॥

(उद्योतः) तदादेः संघातस्येति । वाक्यसंस्कारपक्षे इदम् । दाशतयशब्देन ऋक्संहितेत्यन्ये ॥ एतचेति । इदमपिना सूचितमिति भावः ॥

(प्रत्ययग्रहणपरिभाषाधिकरणम्)

(आक्षेपभाष्यम्)

तत्तर्हि कर्तव्यम् ? ॥

(प्रदीपः) अवयवान्विचार्य सूत्रमाक्षेप्तुं प्रश्नं करोति— तत्तर्हीति । सूत्रमित्यर्थः ॥

(उद्योतः) यदि तत्तर्हीत्यनेनाव्यहितत्वाद् द्वितीयप्रत्ययग्रहणं परामृश्यते तदा केनेदानीमित्यादिभाष्यासंगतिः । नहि तदकरणेऽङ्गकार्ये काचिदनुपपत्तिः । अङ्गसंज्ञायामङ्गस्येत्यधिकृत्य दीर्घादिविधिसंभवादत आह— अवयवानिति ॥

(समाधानभाष्यम्)

न कर्तव्यम् ॥ केनेदानीमङ्गकार्यं भविष्यति ? ॥ प्रत्यय इति प्रकृत्याङ्गकार्यमध्येष्ये ॥

(प्रदीपः) प्रत्यय इति प्रकृत्येति । तेन ब्राह्मणभिस्सा क्रिमिणां पश्येत्यादावैस्दीर्घाद्यभावः ॥

(उद्योतः) भिस्सा ओदनः । क्रिमिशब्दात्लोमादित्वान्नेटापि द्वितीयैकवचनम् । एवं च यदङ्गाधिकारव्यावर्त्यं तदेव प्रत्ययग्रहणव्यापीति भावः । नामः प्रत्ययसमुदायत्वेन प्रत्ययत्वाभाव इति बोध्यम् । एतद्रूपमप्यर्थवत्परिभाषया सिद्धमिति चिन्त्यम् ॥

(आक्षेपभाष्यम्)

यदि प्रत्यय इति प्रकृत्याङ्गकार्यमधीषे । प्राकरोत् उपैहिष्ट । उपसर्गात्पूर्वोऽडाटौ प्राप्नुतः ॥

(प्रदीपः) प्राकरोदिति । लङि परतः पूर्वस्यानियतावधेरडागमो विधीयमान उपसर्गादेः स्यात् ॥

(उद्योतः) अनियतावधेरिति । एवं च देवदत्तः प्राकरोदित्यत्र देवात्पूर्वमप्यट् स्यादिति बोध्यम् ॥

(१०५५ समाधानवार्तिकम् ॥ ७ ॥)

॥ * ॥ सिद्धं तु प्रत्ययग्रहणे यस्मात्स तदादितदन्तविज्ञानात् ॥ * ॥

(भाष्यम्) सिद्धमेतत् । कथम् ? । 'प्रत्ययग्रहणे यस्मात्स प्रत्ययो विहितस्तदादेस्तदन्तस्य च ग्रहणं भवति' इत्येषा परिभाषा कर्तव्या ॥

(प्रदीपः) सिद्धं त्विति । यत्र पूर्वः कार्यित्वेनाश्रीयते तत्र तदादेः कार्यं भवति । यत्र तु प्रत्ययान्तः संघात आश्रीयते तत्र तदादेः प्रत्ययान्तस्य ग्रहणं भवतीत्यर्थः ॥

(उद्योतः) ननु केण इत्यादौ तदन्तग्रहणाभावात्समुच्चयो युक्तोऽत आह— यत्रेति । व्यवस्थितत्वान्न समुच्चयः । तत्र तदन्तविधेः प्रत्ययग्रहणे चापञ्चम्या इति निषेधादिति भावः । प्रत्ययविधौ तु नास्याः प्रवृत्तिर्विहितप्रत्ययविषयत्वादस्या इति बोध्यम् ॥ यत्र त्विति । कृत्तद्धितेत्यादौ । एतेन प्रकृते तदादीत्यंशस्यैवोपयोगेन तदन्तस्येत्ययुक्तमित्यपास्तम् । प्रसङ्गात्तदुक्तेः । एवमेङ्ह्रस्वात्संबुद्धेरित्यादौ तदादेरिति पञ्चम्यन्तमित्यपि बोध्यम् ॥

(अनुयोगभाष्यम्)

कः पुनरत्र विशेषः, एषा परिभाषा क्रियेत, प्रत्ययग्रहणं वा ? ॥

(प्रदीपः) प्रत्ययग्रहणं वेति । प्रत्ययो गृह्यते यस्मिन्सूत्रे तत्, अङ्गसंज्ञासूत्रमित्यर्थः ॥

(उद्योतः) सूत्रप्रश्नस्य प्रक्रान्तत्वात् प्रत्ययग्रहणमित्ययुक्तमत आह— प्रत्यय इति ॥

(समाधानभाष्यम्)

अवश्यमेषा परिभाषा कर्तव्या । बहून्येतस्याः परिभाषायाः प्रयोजनानि ॥

(प्रदीपः) अवश्यमिति । क्रियमाणेप्यस्मिन्सूत्रे परिभाषावश्यं कर्तव्येति व्यापित्वात्परिभाषैवाश्रयणीया न तु सूत्रमित्यर्थः ॥

(१०५६ प्रयोजनवार्तिकम् ॥ ८ ॥)

॥ * ॥ प्रयोजनं धातुप्रातिपदिकप्रत्ययसमासतद्धितविधिस्वराः ॥ * ॥

(भाष्यम्) धातु—देवदत्तश्चिकीर्षति । संघातस्य धातुसंज्ञा आप्नोति ॥ प्रातिपदिक—देवदत्तो

गार्ग्यः । संघातस्य प्रातिपदिकसंज्ञा प्राप्नोति ॥ प्रत्यय—महान्तं पुत्रमिच्छति । संघातात्प्रत्ययोत्पत्तिः प्राप्नोति ॥ समास—ऋद्धस्य राज्ञः पुरुषः । संघातस्य समाससंज्ञा प्राप्नोति ॥ तद्धितविधि—देवदत्तो गार्ग्यायणः । संघातात्तद्धितोत्पत्तिः प्राप्नोति ॥ स्वर—देवदत्तो गार्ग्यः । संघातस्य "ञ्नित्यादिर्नित्यम्" इत्याद्युदात्तत्वं प्राप्नोति । 'प्रत्ययग्रहणे यस्मात्स विहितस्तदादेर्ग्रहणं भवति' इति न दोषो भवति ॥

(प्रदीपः) संघातस्येति । ततश्च सुब्लुक् प्राप्नोति ॥ महान्तं पुत्रमिति । समुदायस्यान्ते सुप्श्रवणात्सुबन्तत्वात्। सत्यां तु परिभाषायां समुदायस्यासुबन्तत्वादवयवस्य सापेक्षत्वादसामर्थ्यान्न भवति प्रत्ययः ॥ ऋद्धस्येति । सुप्सुपेति विवक्षितायामपि संख्यायां समुदायस्य सुबन्तत्वात्समासप्रसङ्गः । परिभाषायां तु सत्यां समुदायस्यासुबन्तत्वात्सुबन्तसमुदायस्य च संख्याविवक्षायां समासाप्रसङ्गात् । अवयवस्य च सापेक्षत्वात्समासाभावः ॥ संघातात्तद्धितोत्पत्तिरिति । ततश्च वृद्धिस्वरौ संघातस्य स्यातां पूर्वस्य च सुपो लुक् ॥

(उद्द्योतः) ततश्चेति । संघातस्य धातुत्वात्प्रातिपदिकत्वाच्चेत्यर्थः । न च समासग्रहणकृतनियमेन प्रातिपदिकत्वं दुर्लभं, नियमस्य भेदसंसर्गद्वारकार्थवत्समुदायविशेषविषयकत्वात् । न च तद्धितान्तस्य तादृशमर्थवत्त्वमित्याशयात्॥ असामर्थ्यादिति । यदि स्यात् तदा महान्तं पुत्रीयतीत्यपि स्यादिति भावः । विवक्षितायामपीति । वस्तुतस्तत्र संख्याविवक्षायां फलाभाव इति वक्ष्यामः ॥ ततश्च वृद्धीति । ननु देवदत्तो गार्ग्यायण इत्यत्र यदि गार्ग्यापत्यं देवदत्तस्तदा समुदायात्प्राप्तिरेव न, असामर्थ्यात् । अपत्यप्रत्ययो ह्यपत्यवता समर्थो न त्वपत्यसमानाधिकरणविशेषणेनापि, यदि देवदत्तो यो गार्ग्यस्तस्यापत्यमित्यर्थस्तर्हि देवदत्तस्य गार्ग्यस्यापत्यमित्याद्युदाहार्यमिति चेन्न । देवदत्तो गार्ग्यायणो भक्तिरस्येति विवक्षायां गोत्रक्षत्रियाख्येभ्य इति वुञ् स्यादित्यभिप्रायात् ॥

(आक्षेपभाष्यम्)

सा तर्ह्येषा परिभाषा कर्तव्या ? ॥

(समाधानभाष्यम्)

न कर्तव्या । एवं वक्ष्यामि—"यस्मात्प्रत्ययविधिस्तदादि प्रत्यये" गृह्यमाणे गृह्यते । ततः "अङ्गम्" अङ्गसंज्ञं च भवति यस्मात्प्रत्ययविधिस्तदादि प्रत्यये ॥

(प्रदीपः) एवं वक्ष्यामीति । योगविभागोऽत्र क्रियते। यस्मात्प्रत्ययविधिस्तदादि प्रत्यय इत्येकं सूत्रम् । अत्र सोपस्कारत्वात्सूत्राणां गृह्यमाणे गृह्यते इति वाक्यशेषः समर्थ्यते । प्रत्यये गृह्यमाणे यस्मात्प्रत्ययविधिस्तदादि गृह्यत इत्यर्थः ॥

(उद्द्योतः) योगविभाग इति । न च द्वितीयस्योपयोगाभावादिदमयुक्तम् । ह्रस्वादङ्गाद् न लुमताङ्गस्येत्यादिव्यवहारनिर्वाहाय द्वितीययोगोप्यावश्यक इति भावः॥ सोपस्कारत्वादिति। पूरणापेक्षत्वादित्यर्थः ॥

(कृद्ग्रहणपरिभाषाधिकरणम्)

(आक्षेपभाष्यम्)

यदि 'प्रत्ययग्रहणे यस्मात्स विहितः तदादेर्ग्रहणं भवति' इत्युच्यते, 'अवतप्तेनकुलस्थितं त एतत्' 'उदकेविशीर्णं त एतत्' सगतिकेन सनकुलेन च समासो न प्राप्नोति ॥

(उद्द्योतः) अवतप्ते इत्यादौ नकुलस्थितविशीर्णशब्दयोरनया परिभाषया क्तान्तत्वाभावात् कृदन्तरूपोत्तरपदत्वाभावाच्च क्तेन 'क्षेपे' तत्पुरुषे कृतीतिसमासविभक्त्यलुकौ न स्याताम् । आद्ये त्वापत्तम् । अन्त्येऽप्यन्तात्स्वरं द्योतम् ॥

(समाधानभाष्यम्)

एवं तर्हि 'प्रत्ययग्रहणे यस्मात्स तदादेर्ग्रहणं भवति' इत्युक्त्वा ततो वक्ष्यामि—'कृद्ग्रहणे गतिकारकपूर्वस्यापि' 'कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणं भवति' इत्येषा परिभाषा कर्तव्या ॥

(आक्षेपभाष्यम्)

कान्येतस्याः परिभाषायाः प्रयोजनानि ? ॥

(१०५७ प्रयोजनवार्तिकम् ॥ ९ ॥)

॥ * ॥ प्रयोजनं समासतद्धितविधिस्वराः ॥ * ॥

(भाष्यम्) समासे—अवतप्तेनकुलस्थितं त एतत् । उदकेविशीर्णं त एतत् । सगतिकेन सनकुलेन च समासः सिद्धो भवति । समास ॥ तद्धितविधि—सांकूटिनम् । व्यावक्रोशी । संघातात्तद्धितोत्पत्तिः सिद्धा भवति । तद्धितविधि ॥ स्वर—दूराद् आगतः दूरादागत इति । 'अन्तः' "थाथघञ्क्ताजबित्रकाणाम्" इत्येष स्वरः सिद्धो भवति 'कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणं भवति' इति॥

(प्रदीपः) सांकूटिनमिति । अणिनुण इति यदि कूटिन्निस्तेतस्माक्रियेन तदा तस्यैवादिवृद्धिः स्यात् ॥ दूरादागत इति । आगम्यते स्मेति कर्मणि क्तः । तत्र गतिस्वरेणाद्युदात्त आगतशब्दः । ततो दूरशब्दस्य स्तोकान्तिकेति समासः । पञ्चम्याः स्तोकादिभ्य इत्यलुक् । अत्र समासान्तोदात्तत्वे प्राप्ते तदपवादकृत्स्वरेणाद्युदात्ते आगत-

शब्दे प्राप्ते सगतेरपि क्तान्तत्वात् स्थानान्तरप्राप्तत्वाद्गतिस्वरस्य बाधकस्यापि बाधकत्वात् थाथघञ्क्तेति सिद्धमन्तोदात्तत्वम् ॥

(उद्योतः) [सांकूटिने अभिविधौ भाव इनुण् ॥ सांकुटिनमिति ह्रस्वपाठोपि भाष्ये ॥] व्यावक्रोशीत्यत्र कर्मव्यतिहारे णच् 'णचः स्त्रियामञ्' न कर्मव्यतिहार इत्यैजनिषेधः ॥ ननु दूरादागतेऽन्तोदात्तत्वं साध्यं तच्च समासस्वरेण सिद्धमत आह— आगम्यते स्मेति । स्मशब्दप्रयोगो भूतकालद्योतनाय । गतिस्वरेण कर्मणि क्तान्ते उत्तरपदे गतिरनन्तर इति विहितेन पूर्वपदप्रकृतिस्वरेण ॥ ततो दूरशब्दस्येति । अयमपि परिभाषासाध्य एव ॥ कृत्स्वरेणेति । कृदुत्तरपदप्रकृतिस्वरेणेत्यर्थः । एतत्प्राप्तिरपि परिभाषयैव ॥ सगतेरपीत्यनेन तत्प्राप्तियोग्यता ॥ ननु गतिस्वरेण पूर्वं बाधितस्य थाथेत्यस्य कथं पुनः प्राप्तिरत आह—स्थानान्तरप्राप्तत्वादिति । समासान्तरप्राप्तत्वादित्यर्थः । यतो गतेरुत्तरक्तान्तस्य यदन्तोदात्तत्वं तस्यैव सोपवादो न तु कारकादुत्तरक्तान्तस्यापीति तात्पर्यम् ॥ गतिस्वरस्य बाधकस्यापीति । थाथादिस्वरबाधकस्यापीत्यर्थः ॥ बाधकत्वादिति । समासान्तरे प्राप्त्या सतिशिष्टत्वेनेति भावः । यद्यपि परिभाषाभावे कृदन्तत्वाभावात् कृत्स्वराप्राप्तौ समासान्तोदात्तत्वेनेदं सिध्यति तथापि परिभाषासत्त्वेपि सिध्यतीत्युपन्यासः ॥

(आक्षेपभाष्यम्)

सा तर्ह्येषा परिभाषा कर्तव्या ? ॥

(समाधानभाष्यम्)

न कर्तव्या । आचार्यप्रवृत्तिर्ज्ञापयति—भवत्येषा परिभाषेति, यदयं "गतिरनन्तरः" इत्यनन्तरग्रहणं करोति ॥ यस्मात्प्रत्यय ॥ १३ ॥

(प्रदीपः) यदयमिति । अनन्तरग्रहणस्य प्रयोजनमभ्युद्धृतमित्यत्राभिशब्दस्य व्यवहितस्य प्रकृतिस्वरो मा भूदिति । यदि चैषा परिभाषा न स्यात् तत उद्धृतशब्दस्य अक्तान्तत्वात् क्तान्त उत्तरपदेऽनन्तरे परतो गतिस्वरो विधीयमानो नैव प्राप्नोति किमनन्तरग्रहणेन । तत् क्रियमाणमस्याः परिभाषायाः सद्भावं ज्ञापयतीत्यर्थः ॥ १३ ॥

(उद्योतः) अस्या इति । एकदेशद्वारा कृत्स्ना परिभाषा ज्ञाप्यत इति भावः । अनन्तरग्रहणे तु तत्सामर्थ्यात्प्रत्ययग्रहणे यस्मादित्यस्या एवोपस्थानमिति तात्पर्यम् । एतच्च विस्तरेण गतिरनन्तर इति सूत्रे षष्ठे उपपादयिष्यते ॥ १३ ॥

(इत्यङ्गसंज्ञा)

(अथ पदसंज्ञाप्रकरणम्)

(१६० पदसंज्ञासूत्रम् १ । ४ । २ आ. ४ सू.)

२५४ सुप्तिङन्तं पदम् ॥ १ । ४ । १४ ॥

(संज्ञाविधिपरिभाषाधिकरणम्)

(आक्षेपभाष्यम्)

अन्तग्रहणं किमर्थम् । "न सुप्तिङ् पदम्" इत्येवोच्येत ? ॥

केनेदानीं तदन्तानां भविष्यति ? ।

तदन्तविधिना ॥

(प्रदीपः) सुप्तिङन्तं पदम् ॥ १४ ॥ अन्तग्रहणमिति । असत्यन्तग्रहणे सुप्तिङामेव पदसंज्ञा स्यात् ततश्चाग्निष्वित्यादौ सात्पदाद्योरिति षत्वनिषेधप्रसङ्ग इत्येतदर्थं यद्यन्तग्रहणं क्रियते तन्न कर्तव्यम् । प्रत्ययग्रहणे यस्मात्स विहित इत्यनन्तरोक्तया परिभाषया तदन्तविधेर्लब्धत्वादिति प्रश्नः ॥

(उद्योतः) सुप्तिङन्तम् ॥ १४ ॥ तिङ्साहचर्यात्सुबपि प्रत्याहारः । न ङिसंबुद्ध्योरिति निषेधाच्च ॥ तदन्तविधेरिति । शब्दस्वरूपस्य विशेष्यत्वात्तदन्तलाभ इति भावः । न च तदन्तविधिलाभेपि व्यपदेशिवद्भावेन केवलप्रत्ययस्यापि प्राप्तौ तदप्रवृत्तये पुनरन्तग्रहणमिति वाच्यम् । हलि सर्वेषामित्यादिनिर्देशैस्तस्येहाप्रवृत्तिकल्पनादिति तात्पर्यम् ॥

(समाधानभाष्यम्)

अत उत्तरं पठति—

(१०५८ समाधानवार्तिकम् ॥ १ ॥)

॥ * ॥ पदसंज्ञायामन्तग्रहणमन्यत्र संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिप्रतिषेधार्थम् ॥ * ॥

(भाष्यम्) पदसंज्ञायामन्तग्रहणं क्रियते ज्ञापकार्थम् । किं ज्ञाप्यम् ? । एतज्ज्ञापयत्याचार्यः "अन्यत्र संज्ञाविधौ प्रत्ययग्रहणं तदन्तविधिर्न भवति" इति ॥ किमेतस्य ज्ञापने प्रयोजनम् ? । "तरप्तमपौ घः" तरप्तमबन्तस्य घसंज्ञा न भवति ॥ किं च स्यात् ? । कुमारी गौरितरा घादिषु नद्या ह्रस्वो भवतीति ह्रस्वत्वं प्रसज्येत ॥

(प्रदीपः) कुमारीगौरितरति । तरबन्तस्य घसंज्ञायां सत्यां तत्रोत्तरपदे परतो ह्रस्वत्वं कुमारीशब्दस्य पुंवद्भावं परत्वाद्बाधित्वा स्यात् । तरपि तु परतो गौरीशब्दस्य न

स्यात् । ततः कुमारिगौरतरेति प्राप्नोति । कुमारगौरितरेति चेष्यते । भाष्ये तु समासप्रदर्शनपरं वाक्यमुपात्तम् ॥

(उद्द्योतः) **परत्वाद्बाधित्वेति** । पुंवद्भावाद् ह्रस्वत्वं विप्रतिषेधेनेत्युक्तेरिति भावः । न च पुनः पुंवत्वम् । सकृद्गतिन्यायाश्रयणात् । अत एव तत्सार्थकम् ॥ **तरपि त्विति** । अत्र पक्षे घसंज्ञकस्योत्तरपदस्य सम्भवेन घेनोत्तरपदविशेषणात् केवलस्य चोत्तरपदत्वाभावात्तत्र परतो न ह्रस्वप्राप्तिरिति भावः ॥ **कुमारिगौरतरेति** । गौरीशब्दे तसिलादिष्विति पुंवत्वं प्राप्नोति । कुमारिगौरीतरेत्यपपाठः । न च तदन्तविध्यभावे ज्ञापितेप्यन्तपदं व्यर्थं प्रत्ययमात्रस्य संज्ञायामपि पदप्रदेशेषु तदन्तविधिना सिद्धेरिति वाच्यम् । पदत्वस्य प्रत्ययाप्रत्ययसाधारणत्वात् । उञि च पदे इत्याद्यसङ्गतेश्चेति दिक् ॥

(आक्षेपभाष्यम्)

यद्येतज्ज्ञाप्यते "सनाद्यन्ता धातवः" इत्यन्तग्रहणं कर्तव्यम् । "कृत्तद्धितसमासाश्च" अन्तग्रहणं कर्तव्यम् । इदं तृतीयं ज्ञापकार्थम् ॥

(प्रदीपः) **सनाद्यन्ता धातव इति** । अन्यथा सनादीनामेव केवलानां धातुसंज्ञा स्यात् । ततश्चाचिकीर्षीदित्यादौ सन एव धातुत्वात्प्रत्ययोत्पत्तौ तदादेरेवाङ्गत्वात्ततः पूर्वोऽट् स्यात् । **कृत्तद्धिते**त्यत्रासत्यन्तग्रहणे केवलयोः कृत्तद्धितयोः प्रातिपदिकसंज्ञा स्यात् । ततश्च भिद् छिद् इति क्विबन्तस्य न स्यात् । अर्थवत्सूत्रेण तु न भवति, अधातुरिति निषेधात् । नापि प्रत्ययलक्षणेन प्राप्नोति, प्रत्ययनिमित्तमन्यस्य यत्कार्यं विधीयते तत्प्रत्ययलोपे भवति, न तु प्रत्ययस्यैव यत्कार्यं तदपि । नह्यसत्कार्यित्वेन वचनशतेनापि शक्यमाश्रयितुम् । केवलस्य च तद्धितस्य प्रातिपदिकसंज्ञायां सत्यामौपगव इत्यत्रापि ङस्याः प्रातिपदिकेऽनन्तर्गतत्वाल्लुग स्यात् । तदन्तविधौ तु दोषानवतारः ॥

(उद्द्योतः) **अधातुरिति** । विशेषणतया क्रियाबोधकस्यापि क्विबन्तादेस्त्वसन्तस्येतिवदत्रेऽधातोरित्युक्त्या धातुत्वानपगमज्ञापनादिति भावः ॥ **प्रत्ययनिमित्तमिति** । लक्षणग्रहणादिति भावः । न च केवलकृतां तद्धितानां च प्रातिपदिकत्वे फलाभावः । ङ्याप्प्रातिपदिकादित्यादौ शब्दरूपं विशेष्यमादाय तदन्तविध्याश्रयणेन तल्लाभात् ॥

(समाधानभाष्यम्)

द्वे तावत्क्रियेते न्यास एव ॥ यदप्युच्यते—"कृत्तद्धितसमासाश्च" इत्यन्तग्रहणं कर्तव्यमिति ॥ न कर्तव्यम् । अर्थवदिति वर्तते । कृत्तद्धितान्तं चैवार्थवत्, न केवलाः कृतस्तद्धिता वा ॥ सुप्तिङन्तम् ॥ १४ ॥

(प्रदीपः) **न केवला इति** । ननु यत्रार्थवत्ता लौकिक्याश्रीयते सा पदस्यैव न तु कृत्तद्धितान्तस्यापि । पदस्यैव लोके प्रयोगार्हत्वात् । अन्वयव्यतिरेकगम्या त्वर्थवत्ता केवलानामपि कृत्तद्धितानामस्तीति किमुच्यते—न केवला इति । एवं तर्ह्यर्थवद्ग्रहणानुवृत्तिसामर्थ्याल्लौकिकार्थप्रत्यासन्नोऽभिव्यक्ततरो योऽर्थः प्रत्ययान्तेषु लक्ष्यते स आश्रीयते इत्यदोषः ॥१४॥

(उद्द्योतः) **लौकिकी**, लोकविदिता । अत्र पक्षेऽर्थवद्ग्रहणात्तदन्तस्यापि न प्राप्नोतीति भावः ॥ **सामर्थ्यादिति** । कृत्तद्धितयोरर्थवत्त्वाव्यभिचारादिति भावः ॥ **लौकिकार्थप्रत्यासन्न इति** । लौकिकार्थकं यत्पदं तदर्थस्य **प्रत्यासन्नः** शास्त्रकृत्कल्पितत्वादिप्रकृतेरर्थः । तदाह—**अभिव्यक्ततर इति** । तदेवाह—**प्रत्ययान्तेष्विति** । कृत्तद्धितप्रत्ययार्थस्तु न तादृशः कल्पितावयवार्थत्वात्तस्य । **प्रत्ययान्तेषु** । सुबन्तेषु सुबर्थत्वात्तस्याः । सुपो द्योतकत्वात्तत्रैव स लक्ष्यते न तु तद्धिते इत्यर्थः । एवमेव पूर्वसूत्रे । इहाप्यर्थाधिकारानुवृत्तिसामर्थ्येन तद्ग्रहः । तदुक्तमनुवृत्तिसामर्थ्यादिति न तु तत्सामर्थ्यादित्युक्तम् । भाष्येप्यर्थवदित्यस्यार्थवत्पदगृहीतार्थवदित्यर्थः ॥ १४ ॥

(१६२ पदसंज्ञानियमसूत्रम् ॥ १ । ४ । २ आ. ५ सू.)

२५५ नः क्ये ॥ १ । ४ । १५ ॥

(नियमस्वरूपस्थापनाधिकरणम्)

(अनुयोगभाष्यम्)

किमर्थमिदमुच्यते । न "सुबन्तं पदम्" इत्येव सिद्धम् ? ॥

(प्रदीपः) **नः क्ये** ॥ १५ ॥ **किमर्थमिति** । लुप्तेपि सुपि प्रत्ययलक्षणेन सिद्धा पदसंज्ञेति प्रश्नः ॥

(उद्द्योतः) नः क्ये ॥ १५ ॥ नलोपार्थत्वात्पदत्वप्रयोजनप्रश्नोऽनुपपन्नोऽत आह—**लुप्तेपीति** ।

(समाधानभाष्यम्)

नियमार्थोऽयमारम्भः । नान्तमेव क्ये पदसंज्ञं भवति नान्यत् । क मा भूत् ? । वाच्यति स्रुच्यति ॥ नः क्ये ॥ १५ ॥

(प्रदीपः) **नान्तमेवेति** । क्य एव नान्तमिति विपरीतनियमो न भवति । न ङिसंबुद्ध्योरिति नलोपनिषेधाज्ज्ञापकात् ॥ **वाच्यतीति** । नन्वत्र क्यचा न भाव्यम् गोसमानाक्षरनान्तादिति वचनात् ॥ एकीयमतं तदित्यदोषः । तन्मते तु क्यङ्क्यषोरनान्तं व्यावर्त्यं तपस्यतीत्यादौ ॥ १५ ॥

(उद्द्योतः) **ज्ञापकादिति** । न च नान्तात्क्यचि ततः क्विपि सुपि प्रत्ययलक्षणेन क्यसत्त्वादनेन नियमेन पदत्वसाध्यावृत्तेः प्राप्तनलोपवारणाय तदावश्यकम् । तथा प्रयोगाभावात् । अन्तरङ्गनलोपस्य बहिरङ्गेण निषेधेन बाधायोगाच्च । वचनं त्वन्यथानियमे चरितार्थमिति भावः । क्ये नान्तं पदमेवेत्यपि न व्याख्यानात् । अ आ इ ई उ ऊ ऋ ॠ ऌ ॡ इति दश **समाना-**

क्षराणि। ल्कारस्य दीर्घाभावान्नवैवेति प्रातिशाख्ये ॥ तपरस्तीति। अत्र पदत्वे रुत्वं स्यादिति भावः ॥ १५ ॥

(१७० पदसंज्ञासूत्रम् ॥ १। ४। २ आ. ६ सू.)

२५७ स्वादिष्वसर्वनामस्थाने ॥ १। ४। १७ ॥

(इष्टानुपपत्तिवारणाधिकरणम्)

(आक्षेपभाष्यम्)

असर्वनामस्थान इत्युच्यते तत्र ते राजा तक्षा 'असर्वनामस्थाने' इति प्रतिषेधः प्रसज्येत ॥

(प्रदीपः) **स्वादिष्वसर्वनामस्थाने ॥ १७ ॥ राजेति।** प्रत्ययलक्षणेन सर्वनामस्थानपरत्वात् ॥

(१०५९ समाधानवार्तिकम् ॥ १ ॥)

॥ * ॥ नाप्रतिषेधात् ॥ * ॥

(भाष्यम्) नायं प्रसज्यप्रतिषेधः—'सर्वनामस्थाने न–' इति ॥ किं तर्हि? ॥ पर्युदासोयम्—यदन्यत्सर्वनामस्थानादिति। सर्वनामस्थानेऽव्यापारः। यदि केन चित्प्राप्नोति तेन भविष्यति। पूर्वेण च प्राप्नोति ॥

(प्रदीपः) **नाप्रतिषेधादिति।** प्रसज्यप्रतिषेधः प्रतिषेधशब्देनोक्तः ॥

(उद्योतः) **स्वादिष्व ॥ १७ ॥** पर्युदासेप्यार्थः प्रतिषेधोऽस्त्येवेत्यत आह—**प्रसज्येति।** शाब्दप्रतिषेध इति भावः ॥

(१०६० समाधानान्तरवार्तिकम् ॥ २ ॥)

॥ * ॥ अप्राप्तेर्वा ॥ * ॥

(भाष्यम्) अथ वा—अनन्तरा या प्राप्तिः सा प्रतिषिध्यते। कुत एतत्?। अनन्तरस्य विधिर्वा भवति प्रतिषेधो वेति। पूर्वा प्राप्तिरप्रतिषिद्धा तया भविष्यति ॥

(प्रदीपः) **अप्राप्तेर्वेति।** प्रसज्यप्रतिषेधाश्रयणेपि न दोष इत्यर्थः ॥

(आक्षेपभाष्यम्)

ननु चेयं प्राप्तिः पूर्वां प्राप्तिं बाधते ॥

(प्रदीपः) **ननु चेयमिति।** परत्वादिति भावः। **स्वादिष्विति** प्राप्तिं प्रतिषेधो बाधते। तत्र यथा देवदत्तस्य हन्तरि हतेपि न पुनः प्रादुर्भाव एवं पदसंज्ञा न स्यादित्यर्थः ॥

(परिहारभाष्यम्)

नोत्सहते प्रतिषिद्धा सती बाधितुम् ॥

(प्रदीपः) **नोत्सहत इति। स्वादिष्विति** प्राप्तिः किं पूर्वस्याः प्राप्तेर्बाधिकास्त्वथ निषेधस्य बाध्येति। तत्र प्राप्तबाधो न युज्यते इत्यप्राप्त्यनुमानं बाध इत्यपवादविषयपरिहारेणोत्सर्गस्य प्रवर्तनात्स्वादिष्विति**प्राप्तिस्तत्रासती कथं बाधकत्वमासादयेत्। यथा वृक्षावित्यत्र **नादिचीति** प्रतिषेधारम्भात्तद्विषये पूर्वसवर्णदीर्घस्याभावाद् वृद्धिं प्रति बाधकत्वाभावाद् वृद्धिः प्रवर्तते तथेह सुबन्तं पदमिति पदसंज्ञेत्यर्थः॥

(उद्योतः) **प्राप्तबाधो न युज्यत इति।** गौरवादिति भावः ॥ **आसादयेदिति।** अनेन देवदत्तहन्तृहतन्यायस्यायमविषय इति दर्शितम्। हननजातीयप्राप्तेरेवाभावादिति भावः ॥

(१०६१ समाधानान्तरवार्तिकम् ॥ ३ ॥)

[॥ * ॥ योगविभागाद्वा ॥ * ॥]

(भाष्यम्) अथ वा योगविभागः करिष्यते—"स्वादिषु" पूर्वं पदसंज्ञं भवति। ततः "सर्वनामस्थानेऽयचि" पूर्वं पदसंज्ञं भवति। ततः "भम्" भसंज्ञं च यजादावसर्वनामस्थान इति ॥

(प्रदीपः) **सर्वनामस्थानेऽयचीति।** असर्वनामस्थाने इत्यत्र नञ् श्रुतो यचीत्यनेन संबन्धं नीयते। यकारादि सर्वनामस्थानं नास्तीति यग्रहणमुत्तरार्थम्। तेनाजादौ सर्वे नामस्थाने पदसंज्ञा निषिध्यते, न तु हलादाविति राजेत्यत्रापि भवति ॥ **भसंज्ञं चेति।** भसंज्ञाविधौ असर्वनामस्थानेनैव नञ्संबध्यते ॥

(उद्योतः) अयजादौ सर्वनामस्थाने इत्यर्थभ्रमं वारयति—**असर्वेति।** यजादौ सर्वनामस्थाने पदं नेत्यर्थः। तादृशार्थे हि योगविभागवैयर्थ्यं स्यादिति भावः ॥ ननु यग्रहणं व्यर्थं तदादिसर्वनामस्थानाभावादत आह—**यकारादीति** ॥ नन्वेवं भविधावपि तथैव संबन्धः स्यादत आह—**भसंज्ञेति** ॥

(आक्षेपभाष्यम्)

यदि तर्हि सावपि पदं भवति, एचः प्लुतविकारे पदान्तग्रहणं चोदितम्। इह मा भूत्—भद्रं करोषि गौरिति। तस्मिन्क्रियमाणेपि प्राप्नोति ॥

(प्रदीपः) **गौरिति।** अत्र **स्वादिष्विति**पदसंज्ञायां सत्यां **पूर्वस्यार्धस्यादुत्तरस्येदुतौ**विति प्रसज्येत ॥

(समाधानभाष्यम्)

वाक्यपदयोरन्त्यस्येत्येवं तत् ॥

(प्रदीपः) वाक्यपदयोरिति। वाक्यस्य चात्र विसर्जनीयोन्त्यो नत्वौकारः॥

(शेषपूरणाधिकरणम्)

(१०६२ आक्षेपवार्तिकम्॥ ४॥)

॥ * ॥ भुवद्वद्भ्यो धारयद्वद्भ्यः पदसंज्ञा ॥ * ॥

(भाष्यम्) एतयोः पदसंज्ञा वक्तव्या। भुवद्वद्भ्यः धारयद्वद्भ्यः॥ स्वादिष्व सर्वनामस्थाने॥ १७॥

(प्रदीपः) भुवद्वद्भ्य इति। तसौ मत्वर्थ इति भसंज्ञा प्राप्तौ पदसंज्ञाविधिः॥ १७॥

(उद्द्योतः) मतुपि स्वादिष्वित्यनेनैव सिद्धमत आह—तसाविति॥ १७॥

(इति पदसंज्ञाप्रकरणम्॥)

(अथ भसंज्ञाप्रकरणम्॥)

(१७२ भसंज्ञासूत्रम्। १। ४। २ आ. ७ सू.)

२५८ यचि भम्॥ १। ४। १८॥

(अनिष्टापत्तिवारणाधिकरणम्)

(१०६३ आक्षेपवार्तिकम्॥ १॥)

॥ * ॥ भसंज्ञायामुत्तरपदलोपे षषः प्रतिषेधः॥ * ॥

(भाष्यम्) भसंज्ञायामुत्तरपदलोपे षषः प्रतिषेधो वक्तव्यः। अनुकम्पितः षडङ्गुलिः षडिकः।

(प्रदीपः) यचि भम्॥ १८॥ षडिक इति। षडङ्गुलिशब्दादनुकम्पायां बह्वचो मनुष्यनाम्न इति ठचि कृते ठाजादावूर्ध्वमिति ङ्गुलिशब्दस्य लोपे यस्येति चेत्यकारलोपे च कृते तुल्यावधिकया भसंज्ञया प्रत्ययलक्षणेन सुबन्तं पदमिति प्राप्तायाः पदसंज्ञाया बाधनाज्जश्त्वं न स्यादिति वचनम्॥

(उद्द्योतः) यचिभम्॥ १८॥ संपूर्णोत्तरपदस्य लोपविधायकाभावादुत्तरपदलोपे इत्यसंगतमत आह—षडङ्गुलीति। एवं च स फलित इति भावः॥ जश्त्वं न स्यादिति। तत्तत्पादसप्ताध्यायीस्थकार्यप्रवृत्तियोग्यतया पूर्वं न जश्त्वमिति भावः॥

(१०६४ समाधानवार्तिकम्॥ २॥)

॥ * ॥ सिद्धमचः स्थानिवत्त्वात्॥ * ॥

(भाष्यम्) सिद्धमेतत्॥ कथम्?। अचः स्थानिवद्भावाद्भसंज्ञा न भविष्यति॥

(प्रदीपः) सिद्धमच इति। अचो लोपस्येत्यर्थः। तत्र भसंज्ञायां विधीयमानायामकारलोपस्य स्थानिवत्त्वादकारान्तमेतद्भसंज्ञां प्रतीति भिन्नावधिविषयत्वाद्भपदसंज्ञयोर्बाध्यबाधकभावाभावः। न पदान्तेति स्थानिवत्त्वनिषेधोत्र न भवति। यत्र पदान्तो विधीयते तत्रासौ निषेधः यथा कौ स्तः कानि सन्तीति। अत्र हि वकारो यकारश्च पदान्तो विधेयः। इह तु पूर्वमेव जश्त्वं प्रवृत्तम्, न त्विदानीं विधेयम्॥

(उद्द्योतः) ननु नाचः स्थानिवत्त्वं किं तु तदादेशस्येत्यत आह—लोपस्येति॥ यत्र पदान्त इति। पदचरमावयव इत्यर्थः॥ न त्विति। उक्तरीत्या पूर्वमप्रवृत्तेरिदं चिन्त्यम्। तस्मादयमर्थः—षषष्ठाजादीतिवचनबोधितद्वितीयादच ऊर्ध्वं लोपविधायकवचनप्रवृत्तिप्रामाण्यादत्र भत्वे न स्थानिवत्त्वप्रतिषेध इति॥

(आक्षेपभाष्यम्)

इहापि तर्हि प्राप्नोति—वागाशीर्दत्तः वाचिक इति॥

(समाधानभाष्यम्)

वक्ष्यत्येतत्—"*सिद्धमेकाक्षरपूर्वपदानामुत्तरपदलोपवचनात् *॥"

(प्रदीपः) सिद्धमिति। उत्तरपदलोपस्य हलजादेशत्वान्नास्ति स्थानिवत्त्वमिति तुल्यावधिकया भसंज्ञया पदसंज्ञा बाध्यते॥

(आक्षेपभाष्यम्)

इहापि तर्हि प्राप्नोति—षडङ्गुलिः षडिक इति॥

(परिहारभाष्यम्)

वक्ष्यत्येतत्— "*षषष्ठाजादिवचनात्सिद्धम्*"

इति॥

(उद्द्योतः) भाष्ये—षषष्ठेति। एकाक्षरपूर्वपदानामित्यत्र षड्भिन्नैकाक्षरेति वाच्यमित्यर्थः॥

(शेषपूरणाधिकरणम्)

(१०६५ आक्षेपवार्तिकम्॥ ३॥)

॥ * ॥ नभोङ्गिरोमनुषां वत्युपसंख्यानम्॥ * ॥

(भाष्यम्) नभोङ्गिरोमनुषां वत्युपसंख्यानं कर्तव्यम्। नभस्वत्। अङ्गिरस्वत्। मनुष्वत्॥

(प्रदीपः) मनुष्वदिति। सत्यां पदसंज्ञायां रुत्वं स्याद् न तु षत्वमपदान्तस्येति वचनात्॥

(उद्द्योतः) नभोङ्गिर इति भाष्ये। अत्र वतिस्तेन तुल्यमित्यादिविहितः॥ ननु मनुष्शब्दे सान्तत्वाभावेन रुत्वाप्राप्तेर्भत्वमनर्थकमत आह—सत्यामिति। मनेरुसिर्बाहुलकादिति भावः॥

(१०६६ आक्षेपवार्तिकम्॥ ४॥)

॥ * ॥ वृषण्वस्वश्वयोश्च॥ * ॥

(भाष्यम्) वृषण इत्येतस्य वस्वश्वयोर्भसंज्ञा व-

त्व्या । वृषण्वसुः । 'वृषणश्वस्य यच्छिरः' 'वृषणश्वस्य मेने' ॥ यचि भम् ॥ १८ ॥

(प्रदीपः) वृषण्वसुरिति । पदत्वे सति पदान्तस्येति निषेधाण्णत्वं न स्याद् नलोपश्च प्रसज्येत । भत्वे तु सत्यल्लोपोऽन इत्यकारलोपोऽत्र न भवति । अङ्गसंज्ञाया अभावात् । अङ्गस्येति च तत्राधिकारात् । उपसंख्यानान्येतानि च्छन्दोविषयाणीत्याहुः ॥ १८ ॥

(उद्योतः) ननु वार्त्तिके वृषणिति णान्तश्रवणेन णान्तशब्दे भत्वं व्यर्थमत आह—पदान्तस्येति । प्रयोगस्यकृतणत्वानुकरणं तदिति भावः ॥ अङ्गसंज्ञाया अभावादिति । अन्तर्वर्त्तिविभक्त्यैका लुप्तत्वाद् वसोश्च प्रत्ययत्वाभावादिति भावः ॥ छन्दोविषयाणीति । भाषायामप्रयोगादिति भावः ॥ १८ ॥

(१७३ भसंज्ञासूत्रम् ॥ १ । ४ । २ आ. ८ सू. ॥)

२५९ तसौ मत्वर्थे ॥ १ । ४ । १९ ॥

(अर्थग्रहणप्रयोजनाधिकरणम्)

(अनुयोगभाष्यम्)

अर्थग्रहणं किमर्थम् । न "तसौ मतौ" इत्येवोच्येत ? ॥

(प्रदीपः) तसौ मत्वर्थे ॥ १९ ॥ अर्थग्रहणमिति । स्वादिष्विति वर्तते तत्रैवं संबन्धः क्रियते—मतौ यः स्वादिर्वर्तेत इति । शब्दे च वृत्त्यसंभवात्तदर्थवृत्तिर्विज्ञास्यते इति प्रश्नः ॥

(उद्योतः) तसौ ॥ १९ ॥ नन्वर्थग्रहणाभावे मतावेव स्यान्नान्यत्रेत्यत आह—स्वादिष्वितीति ॥ मतौ य इति । सामानाधिकरण्ये हि तदनुवृत्तिर्निष्फला स्यादव्यभिचारादिति भावः ॥

(समाधानभाष्यम्)

"तसौ मतौ" इतीयत्युच्यमाने इहैव स्यात्—पयस्वान् यशस्वान् । इह न स्यात्—पयस्वी यशस्वी । अर्थग्रहणे पुनः क्रियमाणे मतुपि च सिद्धं भवति, यश्चान्यस्तेन समानार्थस्तस्मिंश्च ॥

(प्रदीपः) इहैव स्यादिति । मतौ स्वादाविति सामानाधिकरण्येन मुख्यकल्पनया संबन्धे संभवत्यर्थग्रहणं न लभ्यत इति भावः ॥ पयस्वानिति । मत्वर्थीयप्रकरणेऽन्यतरस्यांग्रहणानुवर्तनाद् विनिना मतुब् न बाध्यते ॥

(उद्योतः) मुख्येति । उपरञ्जकतया विशेषणमिति भावः । नन्वसन्तत्वाद्विनिना मतुब् बाध्येतेत्यत आह—मत्वर्थीयेति ।

(आक्षेपभाष्यम्)

यद्यर्थग्रहणं क्रियते पयस्वान् अत्र न प्राप्नोति । किं कारणम् ? । नहि मतुब् मतुबर्थे वर्तते ॥

(प्रदीपः) नहि मतुबिति । उपलक्षणस्यान्योपलक्षणे चरितार्थत्वात् स्वतः कार्यं प्रति निमित्तत्वावगमाभावात् ॥

(उद्योतः) अन्योपलक्षणे । अन्यबोधने । जहल्लक्षणायामतद्गुणबहुव्रीहौ चोपलक्षणस्य कार्ययोगो न दृष्टचर इति भावः ॥

(परिहारभाष्यम्)

मतुबपि मतुबर्थे वर्तते । तद्यथा—देवदत्तशालायां ब्राह्मणा आनीयन्तामित्युक्ते यदि देवदत्तोऽपि ब्राह्मणो भवति, सोऽप्यानीयते ॥ तसौ मत्वर्थे ॥ १९ ॥

(प्रदीपः) मतुबपीति । अस्यास्मिन्निति मतुपोर्थः । स च विन्नादीनामिव मतुपोऽपीति भावः ॥ तद्यथेति । अयमत्रार्थः—यत्र रूपान्तरेणोपलक्षणत्वं रूपान्तरेण च कार्ययोगः प्रतिपाद्यते तत्रोपलक्षणस्याप्युपलक्ष्यरूपसद्भावे सति कार्ययोगो भवति । तद्यथा—देवदत्तशालायां ब्राह्मणा आनीयन्तामित्युक्ते सति ब्राह्मण्ये देवदत्तस्याप्यानयनं भवति । कार्यनिमित्तरूपान्तराभावे तु न भवत्युपलक्षणस्य कार्ययोगः । यथा देवदत्तशाला भिद्यतामिति ॥ १९ ॥

(उद्योतः) ननूपलक्षणस्यापि कार्यान्वयेऽतिप्रसङ्गोत आह—अयमत्रेति । यत्र रूपान्तरेणेति । यथा दृष्टान्ते देवदत्तत्वेनोपलक्षणता ब्राह्मणत्वेन कार्ययोगस्तथा प्रकृते मतुत्वेनोपलक्षणता मत्वर्थकत्वेन कार्ययोग इति भावः ॥ रूपान्तराभावे त्विति । उपलक्ष्यतावच्छेदकरूपस्योपलक्षणेऽभावे त्वित्यर्थः । यथा शालात्वं न देवदत्ते इति भावः ॥ १९ ॥

(१७४ भसंज्ञासूत्रम् ॥ १ । ४ । २ आ. ९ सू०)

२६० अयस्मयादीनि च्छन्दसि ॥ १ । ४ । २० ॥

(१०६७ आक्षेपवार्तिकम् ॥ १ ॥)

[॥ * ॥ उभयसंज्ञान्यपि ॥ * ॥]

(भाष्यम्) **उभयसंज्ञान्यपीति वक्तव्यम् । स सुष्टुभा स ऋक्वता गणेन ॥ अयस्मयादीनि ॥ २० ॥**

(प्रदीपः) अयस्मयादीनि ॥ २० ॥ आनन्तर्याद्भसंज्ञाविधानद्वारेणैव निपातनं प्राप्तमित्याह—उभयसंज्ञान्य-

पीति । अकृतेति । पदत्वात्कुत्वं भत्वाज्जश्त्वं न भवति । जश्त्वविधानार्थपदसंज्ञाबाधनाय भसंज्ञाप्रवर्तनात् तन्निबन्धनकार्याभावः ॥ २० ॥

(उद्योतः) **अयस्मया** ॥ २० ॥ **इत्याहेति** । इत्यत आहेत्यर्थः ॥ ननु भत्वे किं फलमत आह—**जश्त्वमिति** ॥ २० ॥

(इति भसंज्ञाप्रकरणम् ॥)

(अथ वचननियमप्रकरणम् ।)

(१७५ बहुवचननियमसूत्रम् । १ । ४ । २ आ. १० सू.)

२६१ बहुषु बहुवचनम् ॥ १। ४। २१ ॥

(बहुष्वित्यस्य गुणप्रधानताधिकरणम्)

(अनुयोगभाष्यम्)

"बहुषु बहुवचनम्" इत्युच्यते । केषु बहुषु ? ।

(प्रदीपः) **बहुषु बहुवचनम् ॥ २१ ॥ केषु बहुष्विति ।** जातिवादी प्रत्यवतिष्ठते । जातेः प्रातिपदिकार्थत्वे तस्या एकत्वाद्बहुत्वासम्भवात्तत्सहचरितद्रव्यगतं बहुत्वमाश्रयणीयम् । ततश्च वृक्ष इत्यत्रावयवगतबहुत्वसद्भावात्स्याद्बहुवचनमिति भावः ॥

(उद्योतः) **बहुषु** ॥ २१ ॥ ननु बहुष्वित्युक्तेऽस्य प्रत्ययनियमत्वात् प्रकृत्यर्थेषु बहुष्वित्यर्थः सुलभोऽत आह—**जातिवादीति ॥ अवयवगतेति ।** अवयवानामपि वृक्षे शाखेत्यादिव्यवहाराज्जातिसहचरितत्वादिति भावः ॥

(समाधानभाष्यम्)

अर्थेषु ।

(प्रदीपः) अत्रोत्तरम्—**अर्थेष्विति** । अस्याप्ययं भावः—द्रव्यं पदार्थः । तत्राभिधेयगतमेव बहुत्वमाश्रीयते । वृक्षशब्दस्य चावयवी वाच्यो न त्ववयवाः । आकृतिपक्षेपि प्रत्यासत्त्या तदाधारद्रव्यगतं बहुत्वमाश्रीयते, न त्ववयवगतम् । दारा इत्यादौ त्ववयवावयव्यभेदविवक्षायां बहुत्वमाकृत्याधारगतमेव बहुवचनवाच्यमित्यदोषः ॥

(उद्योतः) **नत्ववयवेति** । तादृशपरम्पराग्रहणे मानाभावादिति भावः ॥ नन्वेवं दारा इत्यादावाधारगतबहुत्वाभावादव्याप्तिः । अवयवगततदाश्रयणे तु वृक्षा इत्यादावपि दोषोऽत आह—**दारा इति** । ईदृशाभेदोपचारेण वृक्षा इत्यादौ नानिष्टापादनमनभिधानादिति भावः ॥

(आक्षेपभाष्यम्)

यद्येवं 'वृक्षः वृक्षः' अत्रापि प्राप्नोति । बहवस्तेर्थाः—मूलं स्कन्धः फलं पलाशमिति ॥

(प्रदीपः) इतरोऽगृहीताभिप्राय आह—**यद्येवमिति ।** अर्थशब्दो भवता वस्तुपर्यायः प्रयुक्तः । मूलादीनि च बहूनि वस्तूनि मन्यते ॥

(उद्योतः) **वस्त्विति** । दारा इत्याद्यनुरोधाद्वस्तुपर्याय अवश्याश्रयणीयः । एवं च वृक्ष इत्यादौ दोष इति भावः ॥

(समाधानभाष्यम्)

एवं तर्हि एकवचनं द्विवचनं बहुवचनमिति शब्दसंज्ञा एताः । येष्वर्थेषु स्वादयो विधीयन्ते तेषु बहुषु ॥ केषु च स्वादयो विधीयन्ते ? । कर्मादिषु ॥

(प्रदीपः) **एवं तर्हीति** । अयमर्थः—नेदं स्वातन्त्र्येण विधायकं किं तर्हि ? विहितानामनेन नियमः क्रियते । बहुवचनादिभिर्निष्पन्नशब्दसंज्ञाभिः सुप्तिङोत्र प्रत्याय्यन्ते । तेषां च शास्त्रान्तरेण स्थिते विधाने इदमारभ्यमाणं नियमाय भवति । न त्विदमेव विशिष्टार्थानुवादेन सुप्तिङोर्विधायकमित्येतच्छब्दसंज्ञा एता इत्यनेन प्रदर्श्यते ॥ **येष्वर्थेष्विति ॥** क्वचित्तु पाठः **एवं तर्हि येष्वर्थेष्विति** । एकवचनमित्यादि तु भाष्यं नास्त्येव ॥ अयमर्थः—पञ्चकः प्रातिपदिकार्थः । तथा हि—दधि पश्येत्यादौ विभक्तिश्रवणमन्तरेणापि पञ्चाप्यर्थाः प्रतीयन्ते स्वार्थादयः । विभक्तयस्तु क्वचिद्द्योतकत्वेनापेक्ष्यन्ते । तत्र**अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्तीति** संख्यायां कर्मादिषु च सिद्धा एव स्वादयः । अनेन तु नियम्यन्ते । तत्र कर्मादिशक्त्यैकार्थसमवेत एव बहुत्वे बहुवचनं भवति, न त्ववयवगते ॥

(उद्योतः) नन्ववयवगतबहुत्वाश्रयेण बहुवचने प्रसञ्जिते एकवचनादीनां शब्दसंज्ञात्वकथनमसंगतमत आह—**नेदमिति ॥ विहितानामिति** । न च सुप्तिङ्भ्यामेकवाक्यतया विधायकमेवेदम् । अन्योन्याश्रयपरिहाराय भाविसंज्ञाविज्ञानाश्रयणापत्तेः ॥ **निष्पन्नशब्दसंज्ञाभिरिति** । निष्पन्नशब्दस्य संज्ञाभूतैरित्यर्थः ॥ **प्रदर्श्यत इति** । नियमश्च यद्गतैकत्वादिषु प्राप्तिस्तद्विषय एव, कर्मादिगतैकत्वादिषु च तेषां प्राप्तिरिति न मूलादिगतबहुत्वे तेषां प्राप्तिरिति भावः । तदाह—भाष्ये—**येष्वर्थेष्विति** । इदं द्योत्यपरं पूर्ववाक्योपदर्शितनियमोपपादकत्वात् ॥ तत्र द्योत्यत्वमुपपादयति—**पञ्चक इति** ॥ नन्वेवं विभक्त्युपादानं व्यर्थमत आह—**विभक्तयस्त्विति ॥ कर्मादिशक्त्येति** । अनेन कर्मादिशब्देभ्यो विभक्तीनां वैधर्म्यं दर्शितम् ॥

(समाधानबाधकभाष्यम्)

न वै कर्मादयो विभक्त्यर्थाः । के तर्हि ? । एकत्वादयः ।

(प्रदीपः) **नवै कर्मादय इति । अनभिहितॆ** इति सूत्रारम्भसामर्थ्यात्कर्मादीनां नैव विभक्तिवाच्यत्वमिति मन्यते । तेषां हि विभक्त्यर्थत्वे तिङ्कृत्तद्धितसमासैस्तेषूक्तेषु गतार्थत्वाद्द्वितीयादीनां प्रसङ्ग एव नास्ति किमनभिहिताधिकारेण ॥

(उद्योतः) इतरः प्रत्यासत्त्या कर्मगतबहुत्वे बहुवचनमिति नावयवगतबहुत्वमादायातिप्रसङ्ग इति मत्वाह—**न वै इत्यादि** । भाष्ये ॥ प्राधान्येन सूत्रे विभक्तिद्योत्यतयोक्ता इत्यर्थः । तत्रैकत्वादिषु

बहुष्विति तु वक्तुमशक्यमिति भावः ॥ ननु **कर्मणि द्वितीयेत्याद्य**नुशासनात्कथं तेषामवाच्यत्वमत आह—**अनभिहितेति** । अनुशासनं तु द्योतकत्वेनाप्युपपन्नमिति भावः ॥ **किमनभिहिताधिकारेणेति** । द्योतकत्वे तु यथा प्रकृत्युक्ते भवन्ति एवं तिङादिभिरभिहितेपि स्युरिति तद्व्यावृत्त्यर्थ**मनभिहिता**धिकार आवश्यक इति भावः ॥ **अनभिहितसूत्रे**त्यादेर्ग्रन्थस्यात्र प्रतीके उपयोगश्चिन्त्यः । अत एव **न वै कर्मादय** इति प्रतीकपाठोऽसांप्रदायिक इति बहवः ॥ तदा पञ्चकप्रातिपदिकार्थपक्षोपपादकोयं ग्रन्थः ॥

(समाधानसाधकभाष्यम्)

एकत्वादिष्वपि वै विभक्त्यर्थेष्ववश्यं कर्मादयो निमित्तत्वेनोपादेयाः—कर्मण एकत्वे, कर्मणो द्वित्वे, कर्मणो बहुत्वे इति ।

(प्रदीपः) **एकत्वादिष्वपीति** । वाक्यैकवाक्यत्वे सति महावाक्यं संपद्यते—कर्मण्यनभिहिते यदेकत्वं तत्रैकवचनमित्यादि ॥

(उद्द्योतः) अत्रापि पक्षे एकत्वादीनामाश्रयाकाङ्क्षायां कर्मादीनामेव प्रत्यासत्त्या संभवेन च तत्त्वमित्याशयेनाह—भाष्ये—**एकत्वादिष्वपीति** । सूत्रे प्राधान्येन विभक्तिद्योत्यत्वतयोक्तेष्वित्यर्थः ॥ तत्र प्रत्यासत्तिं दर्शयति—**वाक्यैकेत्यादिना** ॥ **कर्मण्यनभिहिते यदेकत्वमिति** । एकत्वादेराश्रयाकाङ्क्षानिवृत्तये एवमेकवाक्यतेति भावः ॥ भाष्ये—**कर्मादयो निमित्तत्वेनेति** । विशेषणत्वेनेत्यर्थः ॥

(आक्षेपभाष्यम्)

स तर्हि तथा निर्देशः कर्तव्यः । नह्यन्तरेण भावप्रत्ययं गुणप्रधानो भवति निर्देशः॥ इह च 'इत्येके मन्यन्ते' 'तदेके मन्यन्ते' इति परत्वादेकवचनं प्राप्नोति ॥

(प्रदीपः) **स तर्हीति** । बहुत्वे इत्येवमित्यर्थः ॥ **एके मन्यन्त इति** । प्रातिपदिकार्थे एकत्वमप्यस्ति बहुत्वं च । **द्व्येकयोरि**त्यत्र च विशेषानुपादानाद्यावान् कश्चिदेकशब्दार्थः तस्य ग्रहणेन भाव्यम् । तत्र परत्वादेकवचनप्रसङ्गः ॥

(उद्द्योतः) **नह्यन्तरेणेति** । तदर्थे भावप्रत्ययस्य साधुतया विधानेन केवलस्यासाधुत्वादिति भावः ॥ नन्वस्य संख्यावाचकत्वाभावान्न दोषोऽत आह—**द्व्येकयोरित्यत्रेति** ॥

(आक्षेपबाधकभाष्यम्)

"बहुषु बहुवचनम्" इत्येष योगः परः करिष्यते॥

(आक्षेपसाधकभाष्यम्)

सूत्रविपर्यासः कृतो भवति ॥ इह च 'बहुरोदनो' 'बहुः सूप' इति परत्वाद्बहुवचनं प्राप्नोति ॥

(प्रदीपः) **इह चेति** । इह यदि **द्व्येकयोरि**ति योगात्परोयं योगः क्रियते तदा विशेषाभावाद्वैपुल्यरूपस्यापि बहुत्वस्य ग्रहणे सति परत्वाद्बहुवचनप्रसङ्गः ॥

(उद्द्योतः) नन्वस्य पूर्वत्वेन परत्वादित्यसंगतमिति मत्वाह—**इह यदीति** ।

(समाधानभाष्यम्)

नैष दोषः । यत्तावदुच्यते—नह्यन्तरेण भावप्रत्ययं गुणप्रधानो भवति निर्देश इति ॥ [तन्न] अन्तरेणापि भावप्रत्ययं गुणप्रधानो भवति निर्देशः । कथम् ? । इह कदाचिद्गुणो गुणिविशेषको भवति । तद्यथा—'पटः शुक्लः' इति । कदाचिच्च गुणिना गुणो व्यपदिश्यते 'पटस्य शुक्लः' इति । तद्यदा तावद्गुणो गुणिविशेषको भवति 'पटः शुक्लः' इति तदा सामानाधिकरण्यं गुणगुणिनोः, तदा नान्तरेण भावप्रत्ययं गुणप्रधानो भवति निर्देशः । यदा तु गुणिना गुणो व्यपदिश्यते 'पटस्य शुक्लः' इति स्वप्रधानस्तदा गुणो भवति,—तदा द्रव्ये षष्ठी, तदान्तरेण भावप्रत्ययं गुणप्रधानो भवति निर्देशः ॥ न चेह वयमेकत्वादिभिः कर्मादीन्विशेषयिष्यामः । किं तर्हि ? । कर्मादिभिरेकत्वादीन् विशेषयिष्यामः ॥ कथम् ? । एकस्मिन्नेकवचनम् ॥ कस्यैकस्मिन् ? । कर्मणः ॥ द्वयोर्द्विवचनम् । कयोर्द्वयोः ? । कर्मणोः ॥ बहुषु बहुवचनम् । केषां बहुषु ? । कर्मणामिति ॥

(प्रदीपः) **गुणिविशेषक इति** । अत एव वचनादनित्यः षष्ठीसमासप्रतिषेधः । शेषषष्ठ्या वा समासः ॥ **सामानाधिकरण्यमिति** । मतुब्लोपादभेदोपचाराद्वा ॥ **तदा नान्तरेणेति** । गुणिवाचिनः शुक्लशब्दाद्भावप्रत्यये कृते गुणः प्रतीयते नान्यथेत्यर्थः ॥ **द्रव्ये षष्ठीति** । षष्ठीग्रहणं व्यतिरेकविभक्तेरुपलक्षणार्थम् । गुणिनो ह्याधारत्वविवक्षायां सप्तम्यपि भवति । यथैवेह कर्मणि या संख्येति ॥

(उद्द्योतः) ननु **कर्तरि** चेत्यादिषष्ठीसमासनिषेधः स्यादत आह—**अत एवेति** ॥ अनित्यत्वस्य भाष्यानुक्तत्वादाह—**शेषेति** ॥ **सामानाधिकरण्यमे**कार्थवृत्तिता ॥ ननु गुणगुणिनोरत्यन्तभेदात्कथं तदित्यत आह—**मतुब्लोपादिति** ॥ **अभेदोपचाराद्वेति** । उपचरिताभेदस्योद्भूतत्वेन विवक्षणादिति भावः ॥ **गुणः प्रतीयते इति** । निष्कृष्टो गुणः प्रतीयत इत्यर्थः ॥ ननु द्रव्ये षष्ठीतिभाष्यदर्शनाद्विभक्त्यन्तरस्य किमसाधुत्वम् ?, नेत्याह—**उपलक्षणेति** । पटे शुक्ल इति प्रयोगात्सप्तम्यन्तस्य कर्ता-

न्वयद्वारैव क्रियान्वय इति गुणिनो गुणव्यपदेशकत्वेपि सप्तमी भवतीति भावः ॥ अत्र व्यतिरेकविभक्तिर्भावप्रधानतातात्पर्यग्राहकोपलक्षणम् । तेन जात्याख्यायामित्यादिसूत्रस्थभाष्येण न विरोधः ॥ तदान्तरेणापीति । अयं भावः—मञ्चाः क्रोशन्तीत्यादौ यथा मञ्चत्वस्य तत्स्थे आरोपान्मञ्चत्वेनैव तद्बोधस्तथा शुक्लगुणे तस्यैव भेदेनारोपाद्गुणप्रकारक एव गुणबोधः । गुणे भेदेन गुणारोपश्चाश्रयणीय इति । किं बहुना सर्वत्र लक्षणास्थले प्रवृत्तिनिमित्तारोप आश्रयणीय एव ॥ भाष्ये—न चेह वयमिति । एकं कर्मेत्येवमित्यर्थः । एवं च पटस्य शुक्ल इतिवद् भेदनिबन्धनसंसर्गबोधकविभक्त्यैव निष्कृष्टगुणप्रतीतेरुपपन्नत्वाद्भावप्रत्ययापेक्षा नास्तीति भावः ॥

(आक्षेपभाष्यम्)

कथं बहुषु बहुवचनमिति ? ।

(प्रदीपः) **कथमिति** । बहुत्वस्यैकत्वाद्बहाविति भाव्यमिति प्रश्नः ॥

(उद्योतः) **बहुत्वस्येति** । षष्ठ्यन्तपदेन संबन्धिनिर्देशाद्गुणपरतेयेति भावः ॥

(समाधानभाष्यम्)

एतदेव ज्ञापयत्याचार्यः—'नानाधिकरणवाची यो बहुशब्दस्तस्येदं ग्रहणम् । न वैपुल्यवाचिनः' इति ॥ किमेतस्य ज्ञापने प्रयोजनम् ? । यदुक्तम् 'बहुरोदनो बहुः सूप इति परत्वाद्बहुवचनं प्राप्नोति' इति, न स दोषो भवति ॥

(प्रदीपः) **एतदेवेति** । आश्रयगतं बहुत्वं बहुत्वे गुणे आरोप्य निर्देशः कृतः । तस्यैतत्प्रयोजनं भिन्नवस्त्वाधारस्य बहुत्वस्य संख्यारूपस्य ग्रहणं यथा स्यात् । एकाश्रयवर्तिनो वैपुल्यरूपस्य मा भूदिति ॥

(उद्योतः) नन्वसाधुत्वे शङ्किते प्रयोजनकथनमसङ्गतमत आह—**आश्रयगतमिति** । एवमेव **द्वयोर्द्विवचनम्** । **कयोर्द्वयोः । कर्मणोरिति** भाष्ये द्वयोरित्यादिद्विवचनाद्युपपत्तिर्द्रष्टव्या । एवं च धर्मपरत्वेपि न द्विशब्दस्यैकवचनान्तत्वम्, किं तु दारशब्दवद् आरोपितसंख्यानिमित्त एव प्रत्ययस्तस्मात् । समासे तु विभक्त्यश्रवणाद्वारोपे मानाभावेन द्व्येकयोरिति द्विवचनम् । एवं च दारपती अश्लेजसी इत्येव साधुरिति बोध्यम् ॥ **एकाश्रयेति** । एवं च वैपुल्यवाचिग्रहणे बहुवचनमनुपपन्नं स्यादिति भावः ॥

(समाधानभाष्यशेषभाष्यम्)

यदप्युच्यते—'इत्येके मन्यन्ते, तदेके मन्यन्ते' इति परत्वादेकवचनं प्राप्नोतीति ॥ नैष दोषः । एकशब्दोयं बह्वर्थः । अस्त्येव संख्यावाची ॥ तद्यथा—एको द्वौ बहव इति । अस्त्यसहायवाची ॥ तद्यथा—एकाग्नयः । एकहलानि । एकाकिभिः क्षुद्रकैर्जितमिति ॥ अस्त्यन्यार्थे वर्तते । तद्यथा—सधमादो द्युम्न एकास्ताः । अन्या इत्यर्थः ॥ तद्यो ऽन्यार्थे वर्तते तस्यैव प्रयोगः ॥

(प्रदीपः) **एकशब्दोयमिति** । द्व्येकयोरित्यत्र संख्यापदेन द्विशब्देन साहचर्यादेकशब्दस्यास्ति संख्यावाचिनो ग्रहणम् । द्वित्वैकत्वयोश्च द्व्येकशब्दौ वर्तेते इति **द्व्येकयोरिति** द्विवचनेन निर्देशः । अन्यथा बहुवचनं स्यात् । प्रसिद्ध्या च संख्येयार्थत्वमेकादीनामष्टादशान्तानामुच्यते ॥

(उद्योतः) नन्वस्त्वेके **मन्यन्ते** इति प्रयोगोऽन्यार्थस्य, सूत्रे तस्यापि ग्रहणं कुतो नेत्यत आह—**द्व्येकयोरिति** ॥ नन्वेवं बहुवचनापत्तिरत आह—**द्वित्वेति** । नन्वेवमादशतः संख्याः संख्येय इति संख्ययाव्ययेति सूत्रस्थभाष्यसंमतप्रवादविरोधोऽत आह—**प्रसिद्ध्या चेति** । संख्यार्थकत्वं तु क्वाचित्कमप्रसिद्धमित्याशयः ॥

(नियमार्थतानिर्णयाधिकरणम्)

(अनुयोगभाष्यम्)

किमर्थं पुनरिदमुच्यते ? ।

(प्रदीपः) **किमर्थमिति** । लौकिकादेव प्रयोगाद्बहुत्वादिषु बहुवचनादीनां व्यवस्था भविष्यतीति प्रश्नः ॥

(उद्योतः) **लौकिकादेवेति** । महासंज्ञाकरणाच्चेत्यपि बोध्यम् । द्विसाहचर्यादेकबहुशब्दावपि संज्ञाघटकौ संख्याशब्दावेवेति नातिप्रसङ्गः ॥ **बहुत्वादिष्विति** । प्रातिपदिकार्थबहुत्वादिष्वित्यर्थः ॥

(१०६८ समाधानवार्तिकम् ॥ १ ॥)

॥ * ॥ सुप्तिङामविशेषेण विधानाद् दृष्टविप्रयोगाच्च नियमार्थं वचनम् ॥ * ॥

(भाष्यम्) **सुपोऽविशेषेण प्रातिपदिकमात्राद्विधीयन्ते । तिङोऽविशेषेण धातुमात्राद्विधीयन्ते ॥ तत्रैतत्स्याद्यद्यप्यविशेषेण विधीयन्ते नैव विप्रयोगो लक्ष्यते इति । 'दृष्टविप्रयोगाच्च' । दृश्यते खल्वपि विप्रयोगः । तद्यथा—'अक्षीणि मे दर्शनीयानि' 'पादा मे सुकुमाराः' इति । सुप्तिङोरविशेषविधानाद् दृष्टविप्रयोगत्वाच्च व्यतिकरः प्राप्नोति । इष्यते चाव्यतिकरः स्यादिति । तन्नान्तरेण यत्नं**

न सिद्ध्यतीति नियमार्थं वचनम् । एवमर्थमिदमुच्यते ॥

(प्रदीपः) **सुप्तिङामिति** । सुप्तिङ्विधानवाक्ये संख्याविशेषानिर्देशाद् विशेषानुपादानेन तेषां विधानमित्यर्थः ॥ **यद्यपीति** । शास्त्रेऽनुपात्तोप्यर्थः प्रयोगादेव व्यवस्थाप्यत इत्यर्थः । सुपस्तावत् स्वार्थे विधीयमानाः 'स्वार्थद्रव्यलिङ्गसंख्याकर्मादिलक्षणः पञ्चकः प्रातिपदिकार्थः' इति दर्शने संख्यायां सिद्धाः । संख्याविशेषावगतिस्तु लोकात्सिद्धा । तिङोपि कर्तृकर्मणोर्विधीयमानाः संख्यायुक्तयोरेव तयोर्वाचका भविष्यन्ति स्वभावतः । संख्याविशेषः प्रयोगदर्शनादवगम्यते इति भावः ॥ **अक्षीणीति** । द्वित्वेपि लोके बहुवचनं दृश्यत इत्यर्थः ॥ विरुद्धः प्रयोगो **विप्रयोगः** ॥

(उद्योतः) ननु स्वार्थे विहितानां कथमविशेषविधानमत
आह—**संख्याविशेषेति** । इदमुपलक्षणं कारकविशेषस्यापि ।
अत एव **कर्मणि द्वितीये**त्यादेर्नियमत्वसिद्धिः ॥ **प्रयोगादेवेति** ।
असति विरुद्धप्रयोगे प्रयोगाद् व्यवस्था सिध्यतीति भावः ॥ भाष्ये
लक्ष्यतइतीत्यन्ता **दृष्टविप्रयोगत्वाच्चे**त्यादेरवतारणिका ॥ ननु
स्वार्थे विधानेपि संख्यायां विधानार्थमेतदत आह—**सुप इति** ।
स्वार्थद्रव्येति । अत्र **स्वार्थ**शब्देन प्रवृत्तिनिमित्तं **द्रव्य**शब्देन
विशेष्यमतो गुणपरशुक्लादिशब्दे नाव्याप्तिः ॥ **लौकिकादिति** ।
घट इत्यादौ जातौ व्यक्तौ वेत्यादिनिर्णयवदिति भावः । एवं
कर्मणि द्वितीयेत्यादीनामपि नियमत्वं पञ्चकपक्ष एवेति स एव
पक्षो मुख्यः । त्रिकादिपक्षस्त्वभ्युच्चय इति तत्त्वम् ॥ नन्वेवमपि तिङ्-
ष्वनुपपत्तिः, नहि तत्प्रकृत्यर्थः संख्या वक्तुं शक्येत्यत आह—
तिङोपीति ॥ **संख्यायुक्तयोरेव तयोरिति** । तयोः संख्यांश्र-
यत्वादिति भावः ॥ पचन्ति भवति पच्यन्ते भवतीत्यादौ कर्तृ-
कर्मणोर्भवत्यादिघटकतिङर्थसंख्यायुक्तयोरभावादिदं चिन्त्यम् ॥
तस्मादारोपितानारोपितसंख्यायुक्तक्रियाकारकभूतयोरित्युचितम् । उ-
क्तोदाहरणयोरनारोपितैकत्ववती क्रिया । कर्तृगतसंख्यारोपस्तु न
तत्र आरोपितस्यान्यत्रारोपाभावात् ॥ **स्वभावत इति** । इदं चिन्त्य-
मेवं स्वभाववादाश्रयणे **तस्यापत्य**मित्यादेर्वैयर्थ्यापत्तिः शास्त्रारम्भ-
वैयर्थ्यं च । तस्मात्तिङोप्यविशेषेण **धातुमात्राद्विधीयन्त** इति
भाष्यात्**संख्याविशेषाद्यनुपादाने**नेत्यर्थकात्प्रातिपदिकस्येव धातो-
रपि संख्याकारके अर्थः । **लः कर्मणी**त्यपि नियम एव **वर्तमाने**
लडित्यादिना स्वार्थे विहितलानुवादेन तत्प्रवृत्तेः । करणादि च
व्यावर्त्यम् । पाकेन कृतं वरमित्यादौ तत्त्वप्रतीतेः । तिङि तु
नियमे द्योतकाभावात्तदर्थाप्रतीतिरित्यन्यत् ॥ **लः कर्मणि** चेत्यस्यापि
कर्मादिवृत्ताद्धातोर्ल इत्येवार्थो **वर्तमाने लडि**तिवत् । ध्वनितं
चेदं **सुकर्मो**रितिसूत्रे **भावकर्मणो**रित्यस्य भावकर्मवृत्ताद्धातोरि-
त्यर्थं प्रदर्शयता भाष्यकारेण ॥ संख्यायाश्च कारकस्येव क्रियायामे-
वान्वयस्तिङीति ङ्याप्सूत्रे उपपादयिष्यामः ॥ **कर्मादयः** शब्दाः
सुब्नियामकेषु शक्तिपराः, तिङ्संबन्धिशास्त्रेषु शक्तिमत्पराः । अत
एव तिङ्द्योत्यानां प्रकृत्यर्थविशेषणता । नहि शक्तिः साक्षात्क्रिया-
गता । एवं च सुपां तिङां च [द्योतकतेत्येव भाष्यसंमतम् ॥ न
च शत्रादिविषयलस्यापि द्योतकत्वापत्तौ] तत्रापि कर्त्रादेर्विशेषण-
तैव स्यादिति महदनिष्टम् । तिङामसत्त्वभूतभावार्थत्वेन तत्स्थानि-
लस्य तदर्थकत्वेप्यास्यमाने शय्यमाने च गत इत्यादौ शानचि
सत्त्वभूतभावप्रतीत्या तत्स्थानिलस्य तदर्थकत्वाय **भावे** इत्यस्या-
वृत्त्याऽर्थद्वयबोधकत्ववत्कर्त्राद्यंशेप्यावृत्त्या कर्त्रादौ वर्त्तमानात् कर्त्रा-
दावर्थे च लकाराणां विधानेनाक्षतेरित्यलं विस्तरेण ॥ भाष्ये—**निय-
मार्थमिति** । अक्षीणीत्यादेरसाधुत्वमिति भावः ॥ वाक्यभेदेन च
नियमो मन्दमतेरेकवाक्यताज्ञानासम्भवात् । एकवाक्यतापक्षेपि
फलतो नियम एव तद्विनापि तत्र सिद्धेरिति तात्पर्यम् ॥

(अनुयोगभाष्यम्)

अथैतस्मिन्नियमार्थे सति किं पुनरयं प्रत्ययनियम एकस्मिन्नेवैकवचनं, द्वयोरेव द्विवचनं, बहुष्वेव बहुवचनमिति । आहोस्विदर्थनियमः—एकस्मिन्नेकवचनमेव, द्वयोर्द्विवचनमेव, बहुषु बहुवचनमेवेति ? ॥ कश्चात्र विशेषः ? ॥

(१०६९ प्रत्ययनियमपक्षदूषणवार्तिकम् ॥ २ ॥)

॥ * ॥ तत्र प्रत्ययनियमेऽव्ययानां पदसंज्ञाऽभावोऽसुबन्तत्वात् ॥ * ॥

(भाष्यम्) **तत्र प्रत्ययनियमेऽव्ययानां पदसंज्ञा न प्राप्नोति—उच्चैः नीचैरिति । किं कारणम् ? । असुबन्तत्वात् ॥**

(प्रदीपः) **तत्र प्रत्ययनियम इति** । प्रत्यया विशिष्टायां संख्यायां नियता इति निःसंख्येभ्योऽव्ययेभ्यस्तेषामनुत्पादात्पदत्वाभावात्तन्निबन्धनरुत्वाद्यभावप्रसङ्गः ॥

(उद्योतः) ननु प्रत्ययनियमेपि सजातीयापेक्षनियमाश्रयणादव्ययेभ्यः सिध्यतीत्यत आह—**प्रत्यया इति** । सामान्यापेक्षनियमेऽयं दोष इति भावः ॥

(१०७० अर्थनियमस्य निर्दोषतावार्तिकम् ॥ ३ ॥)

॥ * ॥ अर्थनियमे सिद्धम् ॥ * ॥

(भाष्यम्) **अर्थनियमे सिद्धं भवति ।**

(प्रदीपः) **अर्थनियम इति** । अर्था नियता इति तेषु वचनान्तराभावः । प्रत्ययास्त्वनियतत्वादव्ययेभ्योपि सिध्यन्तीत्यर्थः ॥

(उद्योतः) नन्वर्थनियमेपि प्रत्ययनियमस्य त्यागे मानाभावाद्दोष एवात आह—**प्रत्ययास्त्विति** ॥ उभयविधनियमस्यैकवाक्येनालाभादित्यर्थः ॥

(अर्थनियमपक्षाभ्युपगमभाष्यम्)

अस्त्वर्थनियमः ।

(प्रत्ययनियमपक्षाभ्युपगमभाष्यम्)

अथ वा पुनरस्तु प्रत्ययनियमः ।

(आक्षेपस्मारणभाष्यम्)

ननु चोक्तम्-* तत्र प्रत्ययनियमेऽव्ययानां पदसंज्ञाभावोऽसुबन्तत्वाद् * इति ।

(आक्षेपपरिहारभाष्यम्)

नैष दोषः ।

(१०७१ आक्षेपपरिहारसाधकवार्तिकम् ॥ ४ ॥)

॥ * ॥ सुपां कर्मादयोऽप्यर्थाः संख्या चैव, तथा तिङाम् ॥ * ॥

(भाष्यम्) सुपां संख्या चैवार्थः कर्मादयश्च । तथा तिङाम् ।

(प्रदीपः) सुपामिति । कर्मणि द्वितीयेत्यादेः प्रकरणस्य बहुषु बहुवचनमित्यादेश्च स्वादिसूत्रेण सहैकवाक्यता । तिङ्क्ष्वेँ त्विह तस्माद्भेदेन सूत्रद्वयमुपात्तम् । तत्रैकस्मिन्कर्मणीत्येवं गुणगुणिनोः सामानाधिकरण्येन संबन्धे सति संख्याकर्मादयश्च सुपामर्था भवन्ति ॥

(उद्द्योतः) ननु प्रकरणान्तरविहितसुपां तिङां च कथमेतेऽर्था अत आह—कर्मणीति । आकाङ्क्षावशाद्वाक्यैकवाक्यतामनुभूयैव तेषां लक्ष्यसंस्कारत्वमित्यर्थः ॥ स्वादिसूत्रेणेति । तिङ्सूत्रस्याप्युपलक्षणम् पदैकवाक्यतयाऽन्वये तु 'कर्मत्वादियोग्यार्थकप्रातिपदिकार्थमात्रगते एकत्वे प्रथमैकवचनं सुः, कर्मशक्तिसमानाधिकरणे एकत्वे द्वितीयैकवचनमम्' इत्यादिप्रकारेण बोधादन्यत्राव्ययादौ प्राप्तिरुपपादयितुमशक्यैव । किं चार्थनियमप्रकृतार्थापेक्षप्रत्ययनियमशुद्धप्रत्ययनियमेति कथोच्छेद एव । एकवचनादिशब्दे भाविसंज्ञाविज्ञानगौरवं च । अतो वाक्यैकवाक्यतैवात्रैकवाक्यतापदेन विवक्षितेति दिक् ॥ नन्वेवमत्र पाठो व्यर्थोऽत आह—तिङ्क्ष्वेँ त्विति ॥ सुपामर्था इति । द्योत्या इत्यर्थः । तिङ्क्ष्वपि द्योतकतेत्युपपादितम् ॥

(१०७२ अर्थनियमवार्तिकम् ॥ ५ ॥)

॥ * ॥ प्रसिद्धो नियमस्तत्र ॥ * ॥

(भाष्यम्) प्रसिद्धस्तत्र नियमः ।

(प्रदीपः) प्रसिद्धो नियम इति । अर्थनियम इत्यर्थः ॥

(उद्द्योतः) भाष्ये तत्रेति तच्छब्देन पूर्वोपक्रान्तार्थ एव परामृश्यत इत्याह—अर्थेति । पूर्वार्धेन सामान्यापेक्षप्रत्ययनियमासंभवो दर्शितः । अर्थद्वयसत्त्वे कर्मण्येवेत्यादेर्वक्तुमशक्यत्वमिति

(१०७३ प्रत्ययनियमपक्षवार्तिकम् ॥ ६ ॥)

॥ * ॥ नियमः प्रकृतेषु वा ॥ * ॥

(भाष्यम्) अथ वा प्रकृतानर्थानपेक्ष्य नियमः । के च प्रकृताः ? । एकत्वादयः । एकस्मिन्नेवैकवचनं न द्वयोर्न बहुषु । द्वयोरेव द्विवचनं नैकस्मिन्न बहुषु । बहुष्वेव बहुवचनं न द्वयोर्नैकस्मिन्निति ।

(प्रदीपः) नियमः प्रकृतेषु वेति । तुल्यजातीयस्य नियमेन व्यावृत्तिः क्रियत इत्यव्ययेभ्यः स्वादीनामव्यावृत्तिः ॥

(उद्द्योतः) प्रत्ययनियमपक्षेप्यव्ययेभ्यः स्वाद्युत्पत्तये आह—प्रकृतेषु वेति ॥ नन्वेकत्वे एव नान्यत्रेत्येतावल्लभ्यते तत्कथं प्रकृतविषये नियमोऽत आह—तुल्यजातीयस्येति । तत्र प्रकृतापेक्षप्रत्ययनियमेऽयमर्थः: कर्मत्वादियोग्यार्थकप्रातिपदिकाच्चेत्प्रातिपदिकार्थे एव कर्मण्येव नान्यत्र करणादाविति । पचतिकल्पमित्यादौ च वा विभक्तिर्नेष्यते साऽनभिधानाद्वारणीयेत्येवमर्थनियमपक्षेपि बोध्यम् ॥

(प्रत्ययनियमपक्षेऽपि दूषणोद्धारभाष्यम्)

अथ वा आचार्यप्रवृत्तिर्ज्ञापयति—'उत्पद्यन्तेऽव्ययेभ्यः स्वादयः' इति । यदयम् "अव्ययादाप्सुपः" इत्यव्ययाल्लुकं शास्ति ॥ बहुषु बहुवचनम् ॥२१॥

इति श्रीव्याकरणमहाभाष्ये प्रथमाध्यायस्य चतुर्थपादे द्वितीयमाह्निकम् ॥

(प्रदीपः) अथ वेति । भवतु प्रत्ययानां सामान्येन नियमस्तथापि ज्ञापकादव्ययेभ्यः स्वादिसिद्धिरित्यर्थः ॥ २१ ॥

इत्युपाध्यायजैयटपुत्रकैयटकृते महाभाष्यप्रदीपे प्रथमस्याध्यायस्य चतुर्थपादे द्वितीयमाह्निकम् ॥

(उद्द्योतः) पदैकवाक्यतयान्वये सामान्यापेक्षप्रत्ययनियमे चाव्ययेभ्यः स्वाद्युत्पत्तिमाह—भाष्येऽथ वाचार्येति ॥ २१ ॥

इति श्रीशिवभट्टसुतसतीगर्भजनागोजी(गेश)भट्टकृते भाष्यप्रदीपोद्द्योते प्रथमस्य चतुर्थे द्वितीयमाह्निकम् ॥

अथ प्रथमाध्यायस्य चतुर्थपादे तृतीयमाह्निकम् ।

(आदितः सप्तदशम्)

(अथ कारकप्रकरणम्)

(तत्र)

(१७६ अधिकारसूत्रम् ॥ १।४ । ३ आ. १ सू.)

२६३ कारके ॥ २३ ॥

(कारकशब्दार्थनिर्णयाधिकरणम्)

(अनुयोगभाष्यम्)

किमिदं 'कारके' इति १।

(प्रदीपः) कारके ॥ २३ ॥ किमिदमिति । सप्तमीनिर्देशान्न तावत्संज्ञात्वेनाधिकारः । संज्ञाया भाव्यमानत्वात् प्रथमानिर्देशस्य न्याय्यत्वात् । अथ विशेषणत्वेनाधिकारस्तदा कारकाद्दत्तश्रुतयोरित्यादावपादानादिसंज्ञाविकलस्यापि कारकस्य ग्रहणं प्राप्नोति । षड्विधस्यैव चेष्यते । तद्व्यतिरिक्तं च कारकमस्ति । यथा—नटस्य शृणोतीति प्रश्नः ॥

(उद्द्योतः) कारके ॥ २३ ॥ विधेयानिर्देशेन स्वार्थत्वासंभवादयमधिकार एव तत्राधिकारासंभवमाह—सप्तमीति ॥ अथेति । कारके इत्यस्य क्रियायामित्यर्थो विषयसप्तमी चेयमिति भावः ॥ ननु षड्विधकारकातिरिक्तकारकाप्रसिद्धिरत आह—यथेति। क्रियाजनकत्वं हि कारकत्वम् ॥

(समाधानभाष्यम्)

[कारक इति] संज्ञानिर्देशः ।

(प्रदीपः) संज्ञानिर्देश इति । सुपां सुपो भवन्तीति प्रथमायाः स्थाने सप्तमी कृतेति भावः ॥

(अनुयोगभाष्यम्)

किं वक्तव्यमेतत् ? ।

(प्रदीपः) किं वक्तव्यमिति । सप्तमीनिर्देशादयुक्तः संज्ञापक्ष इति भावः ॥

(समाधानभाष्यम्)

नहि ।

कथमनुच्यमानं गंस्यते ? ।

इह हि व्याकरणे ये वा एते लोके प्रतीतपदार्थकाः शब्दास्तैर्निर्देशाः क्रियन्ते, या वा एता कृत्रिमाष्टिघुभादिसंज्ञाः। न चायं लोके ध्रुवादीनां प्रतीतपदार्थकः शब्दः, न खल्वपि कृत्रिमा संज्ञा अन्यत्राविधानात् । संज्ञाधिकारश्चायम् । तत्र किमन्यच्छक्यं विज्ञातुमन्यदतः संज्ञायाः ॥

(प्रदीपः) नहीति । सुब्व्यत्यय उक्तः ॥ न चायमिति । शास्त्रे लोके च प्रसिद्ध्यभावाद्भूतविभक्त्यनुपपत्त्या भाव्यमानविभक्तेः प्रथमायाः स्थाने सप्तमी कृतेति भावः ॥

(उद्द्योतः) भाष्ये समाधाता स्वाशयमाह—इह हीति ॥ प्रतीतेति । अपत्यसमूहादिशब्दा इत्यर्थः ॥ निर्देशाः व्यवहाराः । भादिसंज्ञा इत्यस्य नाभिर्वेति शेषः ॥ निर्देशा इत्यनेनान्वयः ॥ ध्रुवादीनां प्रतीतेति । ध्रुवादीनां वाचकोऽयं शब्दो न लोके प्रतीतपदार्थक इत्यर्थः, किं तु क्रियाजनकपरत्वेनैव प्रसिद्ध इति भावः ॥ अन्यत्रेति । अतः सूत्रादित्यर्थः ॥ तदाशयमाह—शास्त्रे इति ॥

(१०७४ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ कारकइति संज्ञानिर्देशश्चेत्संज्ञिनो निर्देशः ॥ * ॥

(भाष्यम्) कारकइति संज्ञानिर्देशश्चेत्संज्ञिनोपि निर्देशः कर्तव्यः। साधकं निर्वर्तकं कारकसंज्ञं भवतीति वक्तव्यम् ।

(प्रदीपः) संज्ञिनो निर्देश इति । यद्यपि वक्ष्यमाणा ध्रुवादयः संज्ञिनो लभ्यन्ते तथापि विशिष्टसंज्ञी निर्देष्टव्यः । यत् क्रियायाः साधकं ध्रुवादि तत्कारकसंज्ञमपादानसंज्ञं च भवतीति ॥ ननु संज्ञापक्षे कारकसंज्ञाया अपादानादिसंज्ञाभिः समावेशो न प्राप्नोति । एकसंज्ञाधिकारात् ॥ नैष दोषः । ध्रुवमपाय इति योगविभागेन कारकसंज्ञा क्रियते । ततोऽपादानमित्यत्र कारकग्रहणमनुवर्तते ध्रुवमपाय इति च, तेन कारकं सदपादानसंज्ञमित्येवं समावेशः सिद्ध्यतीति । अन्तरेणाप्यनुवृत्तिं वचनसामर्थ्यात्पर्याये सिद्धे समावेशार्थानुवृत्तिर्विज्ञायते । एवं संप्रदानादिसंज्ञास्वपि समावेशो व्याख्येयः । समावेशस्य च प्रयोजनं स्तम्बेरम इत्यादावधिकरणत्वात्सप्तमी कारकत्वात्कृदन्तस्योत्तरपदस्य प्रकृतिस्वरः ॥

(उद्द्योतः) निर्देष्टव्य इत्यस्य 'इति भाष्यार्थः' इति शेषः । तत्फलं तु माणवकस्य पुत्रं पन्थानं पृच्छतीति भाष्य एव वक्ष्यति ॥ भाष्ये साधकमित्यस्य पर्यायो निर्वर्तकमिति—साधकमित्यस्य च क्रियाया इत्यादिः ॥ वचनसामर्थ्यादिति । योगविभागसामर्थ्यादित्यर्थः ॥ स्तम्बेरम इति । चिन्त्यमिदम् । उपपदत्वादेव गतिकारकोपपदात्कृदिति स्वरस्य सिद्धेः । न च स्तम्बशब्द उपपदं, न स्तम्बेशब्द इति वाच्यम् । सुबन्तस्यैवोपपदताया उपपदसंज्ञासूत्रे भाष्ये वक्ष्यमाणत्वात् । तस्माद् ग्रामेवास इत्युदाहार्यम् । तत्र हि थाथादिस्वरः ॥ प्रकृतिस्वर इति । थाथादिस्वरस्तु न । अप्साहचर्यादिरेच एव तत्र ग्रहणात् । भीत्रार्थानां भयहेतुरित्यादावप्यावृत्त्याऽनुवृत्त्या च समावेशो व्याख्येयः ॥

(१०७५ अन्यथानुपपत्तिवार्तिकम् ॥ २ ॥)

॥ * ॥ इतरथा ह्यनिष्टप्रसङ्गो ग्रामस्य समीपादागच्छतीत्यकारकस्य ॥ * ॥

(भाष्यम्) इतरथा ह्यनिष्टं प्रसज्येत । अकारकस्याप्यपादानसंज्ञा प्रसज्येत । क्व ? । ग्रामस्य समीपादागच्छतीति ।

(प्रदीपः) ग्रामस्य समीपादिति । यथा यो वृक्षशाखायाः पतति वृक्षादप्यसौ पतति । एवं यो ग्रामसमीपादागच्छति ग्रामादप्यसावागच्छति । ततश्चापाये ग्रामस्य

ध्रुवता भवति । आगमने तु निर्वर्तकत्वाभावः । समीपविशेषणत्वेनोपात्तत्वात् ॥

(उद्द्योतः) नन्वत्र समीपस्यैवावधित्वं न तु ग्रामस्येत्यत आह—यथेति ॥ ग्रामसमीपादिति । वाटिकादेर्निवर्तकत्वमपादानस्यापि तदभावे तदभावात् ॥ ग्रामादपीति । विभागः संश्लेषपूर्वक एवेतिनियमो नेत्यभिमानः ॥ समीपविशेषणत्वेनेति । एवं च तन्निवर्तकत्वेन न विवक्षितः स इति भावः ॥

(आक्षेपबाधकभाष्यम्)

नैष दोषः । नात्र ग्रामो ऽपाययुक्तः । किं तर्हि ?। समीपम् । यदा च ग्रामोपाययुक्तो भवति, भवति तदा ऽपादानसंज्ञा । तद्यथा—ग्रामादागच्छतीति ।

(प्रदीपः) नात्र ग्राम इति । समीपविशेषणत्वेनोपादानादेव ग्रामस्यापाययोगो नास्ति । स हि संश्लेषपूर्वकः । संश्लेषश्च सन्नसन्वा बुद्ध्या कल्प्यते । स च समीपस्यैव विवक्षितो न ग्रामस्येत्यर्थः । ग्रामात्समीपादिति चोक्ते वस्त्वन्तरापेक्षं ग्रामस्यैव सामीप्यं प्रतीयते न तु ग्रामापेक्षमन्यस्य सामीप्यम् ॥

(उद्द्योतः) ननु ग्रामसमीपविभागे ग्रामविभागोप्यार्थिकोऽस्त्येवेत्यत आह—स हि संश्लेषेति ॥ विवक्षित इति । नात्रेति भाष्यस्य नात्र ग्रामोऽपाययुक्तत्वेन विवक्षित इत्यर्थ इति भावः ॥ नन्वेवं ग्रामात्समीपादित्यादावपि ग्रामस्यापादानत्वं न स्यादत आह—ग्रामोपाययुक्तो भवतीति । ग्रामोऽपाययुक्तत्वेन विवक्षित इत्यर्थ इति भावः ॥ नन्वेवं ग्रामात्समीपादित्यादावपि ग्रामस्यापादानत्वं न स्यादत आह—ग्रामात्समीपादिति ॥ वस्त्वन्तरेति । सामानाधिकरण्येनान्वयादिति भावः ॥

(१०७६ आक्षेपवार्तिकम् ॥ ३ ॥)

॥ * ॥ कर्मसंज्ञाप्रसङ्गोऽकथितस्य ब्राह्मणस्य पुत्रं पन्थानं पृच्छतीति ॥ * ॥

(भाष्यम्) कर्मसंज्ञा च प्राप्नोत्यकथितस्य॥क ?। ब्राह्मणस्य पुत्रं पन्थानं पृच्छतीति ॥

(आक्षेपबाधकभाष्यम्)

नैष दोषः । अयमकथितशब्दोऽस्त्येवासंकीर्तिते वर्तते तद्यथा—कश्चित्कंचित्सञ्चक्ष्याह—'असावत्राकथितः' असंकीर्तित इति गम्यते ॥

(प्रदीपः) सञ्चक्ष्येति । वर्जयित्वेत्यर्थः । वर्जने प्रतिषेध इति ख्यादेशाभावः । वर्जनं च प्रसक्तस्य सजातीयस्यैव भवतीति कारकस्यैव कर्मसंज्ञा भवति न तु ब्राह्मणस्य पुत्रं प्रति विशेषणत्वेनोपात्तस्य ॥

(उद्द्योतः) संचक्ष्येत्यस्य॥क्त्वेत्यर्थेऽसंगतिरत आह—वर्जे······नमिति । ब्राह्मणस्यात्रापादानत्वाप्रसक्तिरिति भावः । यत्र तत्प्रसक्तिपूर्वकं तदविवक्षा तत्रैव तत्प्रवृत्तिरिति तात्पर्यम् ॥

(आक्षेपसा॥धकभाष्यम्)

अस्त्यप्राधान्ये वर्तते । तद्यथा—'अकथितोऽसौ ग्रामे' 'अकथितोऽसौ नगरे' इत्युच्यते यो यत्राप्रधानो भवति । तद्यदा—अप्राधान्येऽकथितशब्दो वर्तते तदैष दोषः—* कर्मसंज्ञाप्रसङ्गोकथितस्य ब्राह्मणस्य पुत्रं पन्थानं पृच्छतीति ॥

(प्रदीपः) तद्यदेति । अप्राधान्यस्य प्रसङ्गनिरपेक्षत्वाद् ब्राह्मणेऽपि पुत्रव॥ावात् । पन्था हीप्सिततमत्वात्प्रधानं, न पुत्रो, नापि ब्राह्मणः ॥

(उद्द्योतः) अप्राधान्यस्येति । प्रधानभिन्नत्वमेव तत्र तु वर्जितप्राधान्यकत्वम् । प्रधानत्वसम्भावनामात्रवत्यपि लोकेऽप्रधानशब्दप्रयोगादिति भावः ॥ पुत्रवद्भावादिति । पुत्रे इवाप्राधान्यस्य सत्त्वादिति भावः ॥ तदेवोपपादयति—पन्था हीति । एवं चानीप्सिततमत्वमेवाप्राधान्यम् ॥ तथायुक्तमित्यपि न सर्वथाऽनीप्सितत्वाभावादिति भावः । तद्यदेत्यनेन भाष्येणात्र पक्षेऽरुचिर्ध्वनिता सा चाग्रे स्फुटीकरिष्यते ॥

(१०७७ आक्षेपान्तरवार्तिकम् ॥ ४ ॥)

॥ * ॥ अपादानं च वृक्षस्य पर्णं पततीति ॥ * ॥

(भाष्यम्) अपादानसंज्ञा च प्राप्नोति। क्व?। वृक्षस्य पर्णं पतति, 'कुड्यस्य पिण्डः पततीति ॥

(प्रदीपः) वृक्षस्य पर्णमिति । ग्रामस्य समीपादित्यत्रापाययुक्तार्थान्तरसद्भावान्नास्ति ग्रामस्यापाययोगः । इह त्वर्थान्तरस्यानिर्देशाद् वृक्षस्यैवापाययुक्तत्वमिति भावः ॥

(उद्द्योतः) ननु ग्रामस्य समीपादित्यत्रेवात्रापि न भविष्यतीत्यत आह—ग्रामस्येति ।

(१०७८ समाधानवार्तिकम् ॥ ५ ॥)

॥ * ॥ न वाऽपायस्याविवक्षितत्वात् ॥ * ॥

(भाष्यम्) न वा एष दोषः । किं कारणम् ?। अपायस्याविवक्षितत्वात् । नात्रापायो विवक्षितः । किं तर्हि ?। सम्बन्धः ॥ यदा त्वपायो विवक्षितो भवति भवति तदाऽपादानसंज्ञा । तद्यथा—वृक्षात्पर्णं पततीति । सम्बन्धस्तु तदा न विवक्षितो भवति न ज्ञायते कङ्कस्य वा कुररस्य वेति ॥

(प्रदीपः) न वाऽपायस्येति । पर्णविशेषणत्वेनैव वृक्षस्य विवक्षितत्वात् । तथा हि—वृक्षमजहत्यपि पर्णे शाखास्थे भूमिं स्पृशति वृक्षस्य पर्णं पततीति प्रयोगो भवति । सति त्ववधौ गतिरपायो भवति नान्यथा, गतिविशेषत्वादपायस्य ॥ न ज्ञायत इति । शब्देनासमर्पणात्सम्बन्धिविशेषस्येति भावः ॥ प्रत्यासत्त्या तु वृक्ष एव सम्बन्धित्वेन प्रतीयते ॥

(उद्द्योतः) नन्वपायाविवक्षायां वृक्षशब्दवैयर्थ्यमत आह—पर्णेति ॥ ननु पतत्पर्णं प्रति वृक्षस्य विशेषणत्वेऽपायविवक्षाप्यावश्यकीत्यत आह—वृक्षमजहत्यपीति ॥ ननु पतेरेवापायत्वेन तस्य चावध्याकाङ्क्षत्वेन तत्त्वमावश्यकमत आह—सति हीति ॥ नन्वेवमन्योन्याश्रयोऽत आह—गतिविशेषत्वादिति । विभागजन्यसंयोगानुकूलव्यापार एवापायः । इह तूत्तरदेशसंयोगानुकूलव्यापार एव पतेरर्थ इति भावः ॥ कङ्ककुररौ वृक्षविशेषौ पक्षिविशेषौ च ॥ प्रत्यासत्त्या त्विति ग्रन्थोपयोगश्चिन्त्यः । पतत्रिपर्णे पतत्यपि वृक्षात्पर्णं पततीति प्रयोगाच्च ॥

(आक्षेपभाष्यम्)

अयं तर्हि दोषः—*कर्मसंज्ञाप्रसङ्गश्चाकथितस्य ब्राह्मणस्य पुत्रं पन्थानं पृच्छति* इति ॥

(प्रदीपः) कर्मसंज्ञाप्रसङ्ग इति । अप्रधानवाच्यकथितशब्दाश्रयण इति भावः ॥

(उद्द्योतः) अप्रधानेति । वस्तुतोऽसंकीर्तितपर्यायेपि दोषः । प्राप्तिपूर्वकाविवक्षायां सर्वथा तदप्राप्तौ चासंकीर्तितत्वं तत्र विवक्षितम् । अत एव नटस्य शृणोतीत्यादौ सर्वथापादानत्वाद्यप्राप्तिविषये कर्मत्वमाशङ्क्य परिगणनेन समाहितमाख्यातोपयोग इति सूत्रे भाष्ये । कारकाधिकाराभावे च पृच्छिकर्मणो निमित्तत्वात्प्राप्तिरत्र शयः । अत एव याचिपृच्छिभिक्षीणामकथितं चेत्युदाहरणता । तत्र हि न कस्यापि प्राप्तिरिति तत्रैव भाष्ये स्पष्टम् ॥

(आक्षेपबाधकभाष्यम्)

नैष दोषः । कारक इति महती संज्ञा क्रियते । संज्ञा च नाम यतो न लघीयः ॥ कुत एतत् ? । लघ्वर्थं हि संज्ञाकरणम् । तत्र महत्याः संज्ञायाः करणे एतत्प्रयोजनम्—अन्वर्थसंज्ञा यथा विज्ञायेत—करोतीति कारकमिति ॥

(प्रदीपः) अन्वर्थसंज्ञेति । महत्याः संज्ञायाः करणादनुमीयते नूनं विशिष्टा ध्रुवादयः संज्ञित्वेन निर्दिष्टाः । यद्विशेषदर्शनात्तदनुरूपा तेषां संज्ञा क्रियते ॥ करोतीति कारकमिति । साध्यत्वेन क्रियैव शब्दात्प्रतीयते इति क्रियाया निर्वर्तकस्य कारकसंज्ञाऽपादानादिसंज्ञा च प्रवर्तते ॥

(उद्द्योतः) नन्वन्वर्थत्वं नाम योगरूढत्वम् । एवं च कथं यौगिकार्थमुद्दिश्य संज्ञाविधानमत आह—महत्या इति ॥ विशिष्टा महासंज्ञोपस्थितक्रियानिर्वर्तकत्वविशिष्टा इत्यर्थः ॥ यद्विशेषेति । क्रियानिर्वर्तकत्वरूपविशेषेत्यर्थः ॥ ननु करोतीत्यस्य निष्पादयतीत्यर्थः । एवं च निष्पादकत्वे लब्धेपि क्रियानिर्वर्तकमित्यर्थालाभोऽत आह—क्रियैवेति । क्रियाया एव शब्देन साध्यत्वप्रतीतेर्निर्वर्तकार्थे कारकशब्दे संबन्ध्याकाङ्क्षायां सैव संबध्यत इति भावः ॥ संप्रदानादीनामपि स्वज्ञानद्वारा जनकत्वं बोध्यम् ॥

(१०७९ आक्षेपसाधकवार्तिकम् ॥ ६ ॥)

॥ * ॥ अन्वर्थमिति चेदकर्तरि कर्तृशब्दानुपपत्तिः ॥ * ॥

(भाष्यम्) अन्वर्थमिति चेदकर्तरि कर्तृशब्दो नोपपद्यते करणं कारकमधिकरणं कारकमिति ॥

(प्रदीपः) अन्वर्थमिति चेदिति । करोतीति कारकमिति यद्याश्रीयते तदा स्वतन्त्रस्यैव कर्तृसंज्ञावत्कारकसंज्ञापि प्राप्नोति न तु करणादीनां कर्तृपरतन्त्राणाम् ॥ कर्तृशब्द इति । कर्तृवाची कारकशब्द इत्यर्थः ॥

(उद्द्योतः) ननु करणादीनामपि क्रियानिर्वर्तकत्वमस्त्येवेत्यत आह—स्वतन्त्रस्येति । स्वतन्त्रवाचिकर्तृपदार्थे ण्वुलो विधानादिति भावः ॥ नन्वकर्तरि कर्तृशब्दाप्रयोग इष्ट एवेत्यत आह—कर्तृवाचीति ॥

(१०८० समाधानवार्तिकम् ॥ ७ ॥)

॥ * ॥ सिद्धं तु प्रतिकारकं क्रियाभेदात्पचादीनां करणाधिकरणयोः कर्तृभावः ॥ * ॥

(भाष्यम्) सिद्धः करणाधिकरणयोः कर्तृभावः । कुतः ? । प्रतिकारकं क्रियाभेदात् । पचादीनां हि प्रतिकारकं क्रिया भिद्यते । किमिदं प्रतिकारकमिति ? । कारकं कारकं प्रति प्रतिकारकम् ।

(प्रदीपः) सिद्धं त्विति । स्वव्यापारे सर्वेषां स्वातन्त्र्यात्तदनुष्ठानद्वारेण प्रधानक्रियायामुपयोगात्कर्तृसन्निधावपि स्वव्यापारस्यानिवर्तनात्पारतन्त्र्यावस्थायामप्यनिवृत्तं कारकत्वमित्यर्थः ॥

(उद्द्योतः) ननु समूहरूपा क्रिया प्रतिकारकं न भिन्नाऽत आह—स्वव्यापार इति । एवं च स्वव्यापारे स्वातन्त्र्यात्कारकत्वं पच्यादिवाच्यसमूहं प्रति पारतन्त्र्यात्करणत्वं चेति भावः ॥ ननु तदा तस्य धात्वर्थत्वाभावात् कथं क्रियात्वं कथं च तदाश्रयत्वेन करणादीनां कारकत्वमिति चेन्न । तदानीं तस्य प्रकृतधात्वर्थत्वाभावेपि कृधात्वर्थत्वाक्षतेः । विभक्तिस्तु प्रकृतधात्वर्थनिबन्धनसंज्ञयैवेति बोध्यम् ॥ तदनुष्ठानद्वारेणेति । तदनुगमनद्वारेणेत्यर्थः ॥

(अनुयोगभाष्यम्)

कोसौ प्रतिकारकं क्रियाभेदः पचादीनाम् ? ।

(१०८१ समधानसाधकवार्तिकम् ॥ ८ ॥)

॥ * ॥ अधिश्रयणोदकासेचनतण्डुलावपनैधोपकर्षणक्रियाः प्रधानस्य कर्तुः पाकः ॥ * ॥

(भाष्यम्) अधिश्रयणोदकासेचनतण्डुलावपनै-

धोपकर्षणादिक्रियाः कुर्वन्नेव देवदत्तः पचतीत्युच्यते । तत्र तदा पचिर्वर्तते । एष प्रधान[स्य] कर्तुः पाकः । एतत्प्रधानकर्तुः कर्तृत्वम् ॥

(उद्द्योतः) तदेति । यदा देवदत्तः पचतीत्युच्यते तदा तत्राधिश्रयणादावित्यर्थः ॥ एवमग्रेपि ॥

(१०८२ समाधानसाधकवार्तिकम् ॥ ९ ॥)

॥ * ॥ द्रोणं पचत्याढकं पचतीति सम्भवनक्रिया धारणक्रिया चाधिकरणस्य पाकः ॥ * ॥

(भाष्यम्) द्रोणं पचत्याढकं पचतीति सम्भवनक्रियां धारणक्रियां च कुर्वती स्थाली पचतीत्युच्यते । तत्र तदा पचिर्वर्तते । एषोऽधिकरणस्य पाकः । एतदधिकरणस्य कर्तृत्वम् ।

(प्रदीपः) सम्भवनक्रियामिति । ग्रहणक्रियामित्यर्थः ॥ धारणक्रियामिति । स्थिरत्वादा क्रियासमाप्तेस्तण्डुलानां धारणमित्यर्थः ॥

(उद्द्योतः) द्रोणं पचतीत्यादेः स्थालीत्यादिः । ज्ञानरूपस्य सम्भवनस्य स्थाल्यां बाधादाह—ग्रहणेति ॥ ननु स्थालीविषयश्चुद्या व्यापारो धारणं स कथं स्थाल्या अत आह—तण्डुलानामिति ॥

(१०८३ समाधानसाधकवार्तिकम् ॥ १० ॥)

॥ * ॥ एधाः पक्ष्यन्त्या विक्लित्तेर्ज्वलिष्यन्तीति ज्वलनक्रिया करणस्य पाकः ॥ * ॥

(भाष्यम्) एधाः पक्ष्यन्त्या विक्लित्तेर्ज्वलिष्यन्तीति ज्वलनक्रियां कुर्वन्ति काष्ठानि पचन्तीत्युच्यन्ते। तत्र तदा पचिर्वर्तते । एष करणस्य पाकः । एतत्करणस्य कर्तृत्वम् ।

(प्रदीपः) एधाः पक्ष्यन्तीति । भविष्यन्निर्देशः कर्तृगतसम्भावनापेक्षः । कर्त्रा हि सम्भावितक्रियाः नियुज्यन्ते । नियुक्ताश्च व्याप्रियन्ते न तु प्रागेव । न त्वत्र भविष्यन्निर्देशस्तन्त्रम् । अनेकार्थत्वाद्धातूनां तादर्थ्याद्वा तद्रूपासङ्गात्करणादिव्यापारे पचेर्वृत्तिर्द्रष्टव्या ॥

(उद्द्योतः) नन्वत्र लृण्निर्देशो व्यर्थोऽत आह—भविष्यदिति ॥ ननु धात्वन्तरवाच्यज्वलनादौ पचेः कथं वृत्तिरत आह—अनेकार्थत्वादिति ॥ तादर्थ्याद्वेति । समूहरूपस्य क्रियार्थत्वात् स्ववाच्यसमूहरूपारोपः करणव्यापारे इत्यर्थः ॥

(१०८४ समाधानसाधकवार्तिकम् ॥ ११ ॥)

॥ * ॥ उद्यमननिपातनानि कर्तुश्छिदिक्रिया ॥ * ॥

(भाष्यम्) उद्यमननिपातनानि कुर्वन्नेव देवदत्तश्छिनत्तीत्युच्यते । तत्र तदा छिदिर्वर्तते । एष प्रधानकर्तुश्छेदः । एतत्प्रधानकर्तुः कर्तृत्वम् ।

(१०८५ समाधानसाधकवार्तिकम् ॥ १२ ॥)

॥ * ॥ यत्तन्न तृणेन तत्परशोश्छेदनम् ॥ * ॥

(भाष्यम्) यत्तत्समाने उद्यमने निपतने च परशुना छिद्यते, न तृणेन तत्परशोश्छेदनम् । अवश्यं चैतदेवं विज्ञेयम् ॥

(प्रदीपः) यत्तन्न तृणेनेति । अन्वयव्यतिरेकाभ्यां करणस्य विशिष्टव्यापारावेशनिदर्शनाय दर्शयति ॥

(उद्द्योतः) नन्वेकत्र करणस्य कर्तृत्वे दर्शितेऽन्यत्रापि ज्ञातुं शक्यत इत परशौ तत्कथनमनुपयुक्तमत आह—अन्वयेति । निदर्शनायेति । प्रतिपादयितुमित्यर्थः । परशौ यथा विशिष्टः करणव्यापार एवं सर्वत्रापीति । एवं च तत्तत्स्वव्यापारे कर्तृत्वात्कारकत्वं फलाश्रयत्वादिविवक्षायां च कर्मत्वादि । कारकत्वं चोपलक्षणं सत्कर्मकारकादिसंज्ञोपयोगीति बोध्यम् ॥ अन्ये तु प्रधानक्रियाजनकोक्तस्वस्वव्यापारे [कर्तारः प्रधानकर्त्रा न्यक्कृतेपि स्वगततत्तद्व्यापारे स्वातन्त्र्यसत्त्वात् । अकुर्वतः साधनत्वानुपपत्तेः । एवं च तत्तद्व्यापारलब्धकरणत्वादिमन्त एव कर्तृपारतन्त्र्येपि स्वस्वव्यापारे] स्वातन्त्र्यसत्त्वात्तद्द्वारा मुख्यक्रियायामपि स्वतन्त्रा इति प्रधानक्रियाकर्तृत्ववन्तोपि । यथा युद्धकर्तारोपि योद्धारो राजनियोगापेक्षणादस्वतन्त्रा अपि नियोगोत्तरं स्वतन्त्रा एव । नियोगमात्रात्तु तन्निष्ठजयादिभाग्राजा । नियोगमात्रेण न मुख्यकर्तर्येव कर्तृत्वव्यवहारोपीत्याहुः ॥

(१०८६ अन्यथानुपपत्तिवार्तिकम् ॥ १३ ॥)

॥ * ॥ इतरथा ह्यसितृणयोश्छेदनेऽविशेषः स्यात् ॥ * ॥

(भाष्यम्) यो हि मन्यते उद्यमननिपातनादेवैतद्भवति छिनत्तीति, असितृणयोश्छेदने न तस्य विशेषः स्याद् यदसिना छिद्यते तृणेनापि तच्छिद्येत ॥

(१०८७ आक्षेपवार्तिकम् ॥ १४ ॥)

॥ * ॥ अपादानादीनां त्वप्रसिद्धिः ॥ * ॥

(भाष्यम्) अपादानादीनां तु कर्तृत्वस्याऽप्रसिद्धिः । यथा हि भवता करणादीनां कर्तृत्वं निदर्शितं न तथाऽपादानादीनां निदर्श्यते ॥

(प्रदीपः) न तथेति । नह्यपादाने ग्रामे ग्राम आगच्छतीति प्रयोगोस्ति ॥

(उद्द्योतः) भाष्ये—अपादानादीनामिति । आदिना सम्प्रदानम् । बहुवचनं तु प्रयोगबाहुल्याभिप्रायेण । एवं च वयोः कारकसंज्ञाऽप्राप्तिरिति भावः । कर्मणः कर्तृत्वं तु कर्मवत्कर्मणेति-

सूत्रेण स्पष्टमेवोक्तमिति तत्र दर्शितम् ॥ नन्ववधीभवनमेव तद्व्यापारोऽत्र आह—नहीति । अपादाने ग्रामे इति । अपादानभूतग्रामविषये इत्यर्थः ।

(१०८८ समाधानवार्तिकम् ॥ १५ ॥)

॥ * ॥ न वा स्वतन्त्रपरतन्त्रत्वात्तयोः पर्यायेण वचनं वचनाश्रया च संज्ञा ॥ * ॥

(भाष्यम्) न वा एष दोषः । किं कारणम् । स्वतन्त्रपरतन्त्रत्वात् । सर्वत्रैवात्र स्वातन्त्र्यं पारतन्त्र्यं च विवक्षितम् ॥ तयोः पर्यायेण वचनम् । तयोः स्वातन्त्र्यपारतन्त्र्ययोः पर्यायेण वचनं भविष्यति ॥ वचनाश्रया च संज्ञा भविष्यति । तद्यथा—बलाहकाद्विद्योतते विद्युत् । बलाहके विद्योतते । बलाहको विद्योतत इति ॥

(प्रदीपः) **बलाहकादिति** । निःसरणाङ्गे विद्योतने द्युतिर्वर्तते पृथग्भावश्च विवक्षित इत्यपादानत्वम् ॥ **बलाहक इति** । स्थित्यङ्गे द्योतनेऽत्र द्युतिर्वर्तते । बलाहके स्थित्वा ज्योतीरूपा विद्युद् विद्योतत इत्यर्थः ॥ **बलाहक इति** । विद्युतो बलाहकस्य चाभेदविवक्षायामयं प्रयोगः ॥

(उद्योतः) भाष्ये—**वचनं** विवक्षा ॥ **वचनाश्रया चेति** । कादाचित्कस्वातन्त्र्यविवक्षाश्रया च कारकसंज्ञा भविष्यति तात्कालिकपारतन्त्र्यविवक्षाश्रया चापादानसंज्ञेत्यर्थः ॥ नन्वपादानस्य कर्तृत्वं न दृष्टमित्यतो भाष्ये—**तद्यथेत्यादि** ॥ ननु विद्युद्बलाहकयोरविभागात्कथं निःसरणमत आह—**पृथग्भाव इति** । बौद्धो भेद इत्यर्थः ॥ नन्वत्रार्थे बलाहकस्याधारत्वानुपपत्तिरत आह—**स्थित्यङ्ग इति** ॥ **अभेदविवक्षायामिति** । धूमज्योतिःसलिलमरुतां संघातस्य मेघपदार्थत्वविवक्षायामिति भावः ॥

(अनुयोगभाष्यम्)

किं तर्हुच्यते—'*अपादानादीनां त्वप्रसिद्धिः*' इति ? ॥

(उद्योतः) भाष्ये—**किं तर्हीति** । अपादानस्य कर्तृत्वप्रसिद्धौ तेषां कर्तृत्वाप्रसिद्धिरित्यभिप्रायेण कथमपादानादीनां त्वप्रसिद्धिरिति वार्तिकं व्याख्यातमित्यर्थः ॥

(समाधानभाष्यम्)

एवं तर्हि न ब्रूमः—'अपादानादीनां कर्तृत्वस्याप्रसिद्धिः' इति । पर्याप्तं करणाधिकरणयोः कर्तृत्वं निदर्शितमपादानादीनां कर्तृत्वनिदर्शनाय, पर्याप्तो ह्येकः पुलाकः स्थाल्या निदर्शनाय ॥ किं तर्हि ? ॥ संज्ञाया अप्रसिद्धिः ॥

(प्रदीपः) **पर्याप्तमिति** । स्वव्यापारानुष्ठानमन्तरेण प्रधानक्रियायामुपयोगाभावात् । ग्राम आगच्छतीत्यर्थान्तरावगमादपादानव्यापारानवसायात्प्रयोगाभावः । एवं ब्राह्मणाय ददातीत्यर्थे ब्राह्मणो ददातीति प्रयोगाभावः । शब्दशक्तिस्वाभाव्याच्चापादानसम्प्रदानव्यापारे धातुर्न वर्तते । वस्तुतस्त्वपादानस्यावधिभावेनावस्थानं व्यापारोऽस्ति सम्प्रदानस्याप्यनुमननादिलक्षणः प्रतीयमानोऽपि व्यापारः कारकव्यपदेशनिबन्धनम् । यथा प्रविश पिण्डीमिति ॥

(उद्योतः) उत्तरयति—**एवं तर्हीत्यादिना** । एवं तर्हि—'अपादानादीनां त्वप्रसिद्धिः' इति वाक्यं नोक्ताभिप्रायं किं तर्हीत्यन्वयः ॥ **पर्याप्तमिति** । कर्मण इवेत्यर्थः ॥ तद्व्याचष्टे—**स्वेत्यादि** ॥ नन्वेधाः पचन्तीतिवद् ग्राम आयातीति प्रयोगः स्यादत आह—**ग्राम आगच्छतीति** ॥ ननु काष्ठं पचतीत्यत्राप्यर्थान्तरावगमस्तुल्यः, एवमपि तद्व्यापारस्य धात्वर्थत्वेऽपादानादिव्यापारोऽपि तथा स्यादत आह—**शब्दशक्तीति** ॥ नन्वपादानादिषु व्यापाराभावादेव न तथा प्रयोगोऽत आह—**वस्तुतस्त्विति** ॥ ननु तस्य प्रकृतधातुवाच्यत्वाभावात्कथं कर्तृप्रत्ययान्तकारकव्यपदेशोऽत आह—**प्रतीयमानोऽपीति** । धात्वर्थत्वाभावेऽपि ग्रामादिपदैरेव तस्य प्रतीत्या तन्निरूपितं कारकत्वं कारकशब्दघटककृधात्वर्थत्वात्तस्य व्यापारस्येति भावः ॥

(आक्षेपभाष्यम्)

यावता सर्वत्रैवात्र स्वातन्त्र्यं विद्यते पारतन्त्र्यं च । तत्र परत्वात्कर्तृसंज्ञैव प्राप्नोति ॥

(प्रदीपः) **परत्वादिति** । अपादानादीनामवकाशो यदा स्वातन्त्र्यं नास्ति । कर्तृसंज्ञाया अवकाशो देवदत्तः पचतीति ॥ ननु सर्वत्र स्वातन्त्र्यस्य सद्भावान्नास्ति कर्तृसंज्ञावियुक्तोऽपादानादिसंज्ञानामन्यत्रावकाशः ॥ सत्यमेतत् । पूर्वपक्षस्त्वयं तत्र च न्यायाभासेनैव भाव्यम् । अन्यथा पूर्वपक्ष एव न स्यात् ॥

(उद्योतः) **न स्यादिति** । अयं भावः—यद्यनवकाशत्वादपादानादिसंज्ञाः स्युस्तदा स्थाली पचतीति न स्यादिति ॥

(समाधानभाष्यम्)

अत्रापि *न वा स्वतन्त्रत्वात्तयोः पर्यायेण वचनं वचनाश्रया च संज्ञा* इत्येव ॥

(प्रदीपः) **अत्रापीति** । उद्भूतस्वातन्त्र्यविवक्षायां कर्तृसंज्ञा—यथा स्थाली पचतीति । उद्भूतपारतन्त्र्यविवक्षायां तु न्यग्भावात्सदपि स्वातन्त्र्यं स्वकार्ये न प्रयुङ्क्ते । यथा राजसन्निधौ तदनुपयोगि स्वकार्यममात्या नारभन्ते ॥

(उद्योतः) नन्वेवमपि स्वव्यापारं प्रति स्वातन्त्र्यस्यानिवर्तनात् कर्तृत्वं न व्यावर्तितमत आह—**उद्भूतेति** । स्वतन्त्रपदसामर्थ्यादित्यर्थः । स्वातन्त्र्ये उद्भूतत्वं च विवक्षितप्रकृतप्रधानसंपूर्णधात्वर्थाश्रयत्वरूपत्वमेव । पारतन्त्र्ये उद्भूतत्वं च प्रकृतधात्वर्थानाश्रयत्वरूपत्वमेवेति बोध्यम् ॥ **यथा राजेति** । तदा हि राजा स्वकार्यभागिति तत्रामात्यानां न स्वातन्त्र्यं तदवाये तु राजकार्येऽपि तेषां नियोगात् स्वातन्त्र्यमेव, तथा कर्तृसन्निधाने स्थाल्यादियत्नस्य धात्व-

वाच्यत्वात्तेषां पारतन्त्र्यमेव तद्व्यवाये तयत्नस्यापि तद्वाच्यत्वाद् स्वातन्त्र्यमिति भावः । अन्यथाऽपादानादीनां निरवकाशत्वादित्याशयः ॥

(आक्षेपभाष्यम्)

यथा पुनरिदं भवता स्थाल्याः कर्तृत्वं निदर्शितं संभवनक्रियां च धारणक्रियां च कुर्वती स्थाली स्वतन्त्रेति ॥ क्वेदानीं परतन्त्रा स्यात्? ॥

(उद्द्योतः) भाष्ये—यथा पुनरिति । येन प्रकारेणेत्यर्थः ।

(समाधानभाष्यम्)

यत्तत्प्रक्षालनं परिवर्तनं वा ॥

(उद्द्योतः) क्वेति प्रश्ने उत्तरं यत्तदिति ॥

(निराकरणभाष्यम्)

न वा एवमर्थं स्थाल्युपादीयते प्रक्षालनं परिवर्तनं च करिष्यामीति । किं तर्हि संभवनक्रियां धारणक्रियां च करिष्यतीति तत्र चासौ स्वतन्त्रा ॥ क्वेदानीं परतन्त्रा? ॥

(प्रदीपः) न वा एवमर्थमिति । प्रक्षालनाद्यभावेपि पाकनिष्पादात्तेषां तत्रानङ्गत्वात् ॥

(उद्द्योतः) तत्खण्डयति—नवेति ॥

(समाधानभाष्यम्)

एवं तर्हि स्थालीस्थे यत्ने कथ्यमाने स्थाली स्वतन्त्रा । कर्तृस्थे यत्ने कथ्यमाने परतन्त्रा ॥

(उद्द्योतः) स्थालीस्थे यत्न इति । अत्र यत्नशब्देन व्यापारसामान्यम् ॥

(आक्षेपभाष्यम्)

ननु च भोः कर्तृस्थेपि यत्ने कथ्यमाने स्थाली संभवनक्रियां धारणक्रियां च करोति तत्रासौ स्वतन्त्रा । क्वेदानीं परतन्त्रा स्यात्? ॥

(उद्द्योतः) समीचीने समाधाने उक्तेपि तद्बुद्ध्योक्तमेव पुनराह—ननु चेति ॥

(समाधानभाष्यम्)

एवं तर्हि प्रधानेन समवाये स्थाली परतन्त्रा, व्यवाये स्वतन्त्रा । तद्यथा—अमात्यानां राज्ञा सह समवाये पारतन्त्र्यं, व्यवाये स्वातन्त्र्यम् ॥

(उद्द्योतः) स्वाश्रयं प्रकटयति समाधाता—एवं तर्हीति । प्रधानेन समवाये इति ॥ धात्वर्थानाश्रयायाः प्रधानधात्वर्थाश्रयेण समवाये इत्यर्थः ॥ व्यवाये इति । तस्य धात्वर्थाश्रयत्वाभावे स्थाल्या एव धात्वर्थाश्रयत्वे इत्यर्थः ॥ राज्ञा सहेति । व्यवहारदृष्टत्वाचाश्रयराशेत्यर्थः । अस्याशय उक्तः ॥

(अनुयोगभाष्यम्)

किं पुनः प्रधानम्? ।

(प्रदीपः) किं पुनः प्रधानमिति । सामग्रीतः क्रियोत्पादात्सर्वेषां तत्र सामान्यान्न कस्यचित्प्राधान्यमिति भावः ॥

(उद्द्योतः) सामान्यादिति । समानत्वादित्यर्थः ॥

(समाधानभाष्यम्)

कर्ता । कथं पुनर्ज्ञायते—कर्ता प्रधानमिति? । यत्सर्वेषु साधनेषु संनिहितेषु कर्ता प्रवर्तयिता भवति ॥

(प्रदीपः) कर्ता प्रवर्तयितेति । तदधीनप्रवृत्तिनिवृत्तित्वात्करणादीनां तस्य च प्रागन्यतः शक्तिलाभात्प्रतिनिध्यदर्शनात्करणाद्यभावेप्यास्ते शेते इत्यादौ केवलस्य कर्तुर्दर्शनात्कर्तृरहितानां करणादीनामदर्शनात्प्राधान्यं कर्तुरित्यर्थः ॥

(उद्द्योतः) नन्वन्यतराभावेपि प्रवृत्तेरदर्शनात्सर्वस्य प्रवर्तयितृत्वमविशिष्टं साधकतमत्वात्करणस्यैव च प्राधान्यमत आह—तदधीनेति । भाष्ये—प्रवर्तयितेत्यस्य साधनानामिति शेषः । अनेन कारकचक्रप्रयोक्तृत्वं कर्तुः स्वातन्त्र्यमित्युक्तम् ॥ नन्वीप्सिततमत्वेन कर्मणः प्राधान्यमत आह—तस्य चेति । कर्तुरित्यर्थः ॥ अन्यतः प्रागिति । अन्येभ्यः कारकेभ्यः प्रागित्यर्थः । नैवं करणादीनामिति भावः ॥ प्रतिनिधीति । करणादीनां हि सोमादीनां स दृश्यते न तु कर्तुरिति भावः ॥ करणाद्यभावेपीति । अन्वयव्यतिरेकाभ्यां कर्तुः प्राधान्यमित्यर्थः ।

(आक्षेपभाष्यम्)

ननु च भोः प्रधानेनापि वै समवाये स्थाल्या अनेनार्थः अधिकरणं कारकमिति ।

नहि कारकमित्यनेनाधिकरणत्वमुक्तम्, अधिकरणमिति वा कारकत्वम् । उभौ चान्योन्यविशेषकौ भवतः । कथम्? । एकद्रव्यसमवायित्वात् । तद्यथा गार्ग्यो देवदत्त इति । नहि गार्ग्य इत्यनेन देवदत्तत्वमुक्तं देवदत्त इत्यनेन वा गार्ग्यत्वम् । उभौ चान्योन्यविशेषकौ भवत एकद्रव्यसमवायित्वात् ॥

(प्रदीपः) उभौ चान्योन्यविशेषकाविति । ततश्च स्वातन्त्र्यपारतन्त्र्ययोर्युगपद्विरोधाद्विशेषणविशेष्यत्वे न प्रकल्पेते इत्यर्थः ॥

(उद्द्योतः) भाष्ये—अनेनेति ॥ कारकव्यपदेशेनेत्यर्थः । अयं व्यवहार इष्यते तत्रोद्भूतस्वातन्त्र्याभावाद्यथा कर्तृशब्दाप्रवृत्तिस्तथा तदर्थककारकशब्दस्याप्यप्रवृत्तिः स्यादिति भावः ॥ ननु पुनरुक्तत्वादेवं व्यवहारोऽनिष्ट एवेत्यत आह नहीति । एवं च न पौनरुक्त्यमिति भावः । किं तु विशेषणविशेष्यभाव

इत्याह—**उभौ चेति** । तदाशयं पूर्वपक्षसाधकत्वेनाह—**तत्रोति** ॥ नन्वेताभ्यामेकस्यैव द्रव्यस्य बोधेन तयोर्भेदनियतस्य परस्परसंबन्धस्याभावादन्योन्यविशेषकावित्ययुक्तमिति पृच्छति—भाष्ये—**कथमिति** ॥ उत्तरयति—**एकद्रव्यसमवायित्वादिति** । शब्दद्वयोपात्ते एकत्र द्रव्ये उभयोः समवायात्संबन्धादित्यर्थः ॥ **अन्योन्यविशेषकावि**त्यस्य परस्परं विशेष्यविशेषणभावं प्राप्तावित्यर्थः । **एकद्रव्यसमवायित्वा**दित्यनेन द्रव्यैक्येपि धर्मभेदे विशेष्यविशेषणभावो न तूभयैक्ये इति दर्शितम् । यद्वा कारकशब्दोपात्तद्रव्यस्याधिकरणत्वरूपोर्थोऽधिकरणपदोपात्तद्रव्यस्य कारकत्वरूपोर्थः परिच्छेदक इत्यर्थः ॥ ननु भिन्नद्रव्यवृत्तिधर्मयोः कथं परस्परपरिच्छेदकत्वमत आह—**एकेति** । शब्दद्वयोपात्तैकद्रव्यसंबद्धत्वादित्यर्थः ॥

(समाधानभाष्यम्)

एवं तर्हि सामान्यभूता क्रिया वर्तते । तस्या निर्वर्तकं कारकम् ॥

(**प्रदीपः**) **एवं तर्हीति** । सर्वेषां कारकाणां साध्यत्वेन साधारणी क्रिया ततश्च सर्वेषां तस्यां कर्तृत्वम् । अवान्तरव्यापारविवक्षायां तु करणादिरूपत्वम् । यथा मातापित्रोरपत्योत्पादने कर्तृत्वं भेदविवक्षायां त्वयमस्यामियमस्माज्जनयतीत्यधिकरणत्वमपादानत्वं च व्यवतिष्ठते । कर्तृसंज्ञा तु करणत्वाद्यवस्थायां न भवति । **स्वतन्त्रः कर्ते**त्यत्र कारकत्वादेव स्वातन्त्र्ये लब्धे पुनः स्वतन्त्रश्रुतिर्नियमार्था तेन स्वतः स्वातन्त्र्यमेव यस्य कर्तृसंज्ञा तस्य, न तु पारतन्त्र्यसहितस्वातन्त्र्ययुक्तस्य । कारकसंज्ञा तु वस्तुस्थित्या विद्यमानमुद्भूतत्वेनाविवक्षितमपि स्वातन्त्र्यमाश्रित्य करणादीनां विधानसामर्थ्यात्प्रवर्तते । यत्र च शक्तीनां निमित्तनिमित्तिभावेन युगपद्विवक्षा तत्र संज्ञानां विप्रतिषेध उच्यते । यथा धनुषा विध्यतीति विनापायविवक्षया धनुषः साधकतमत्वाभावात् संज्ञाद्वयप्रसङ्गे परत्वात्करणसंज्ञा । असिश्छिनत्तीति सत्येव साधकतमत्वे स्वातन्त्र्यस्य विवक्षितत्वात्परत्वात्कर्तृसंज्ञा । तदा तु तैक्ष्ण्यादीनां करणत्वम् । तैक्ष्ण्यादीनां तु कर्तृत्वविवक्षायामात्मनः करणत्वम् । तैक्ष्ण्यमेव हि विवक्षावशाद्द्विधावतिष्ठते कर्तृत्वेन करणत्वेन च । वस्तुस्थित्या त्वेक एवार्थात्मेति कर्तृत्वं करणत्वस्य बाधकमुच्यते ॥

(**उद्योतः**) यद्यपि तद्व्यवायकालिकस्वातन्त्र्यमादाय तदापि कारकत्वव्यवहारस्तत्कालिकपारतन्त्र्यमादाय चाधिकरणत्वव्यवहार इति शक्यते वक्तुं तथापि प्रकारान्तरेणापि समाधातुमाह—**एवं तर्हीति** । भाष्य ॥ ननु सर्वेषामेकक्रियाभावात्सामान्यभूतेत्यनुपपन्नमत आह—**सर्वेषामिति** । **साधारणीति** । प्रधानक्रिया तत्तद्व्यापारजन्यत्वेन सर्वसाधारणीति भावः ॥ **तस्यां कर्तृत्वमिति** । जनकत्वादिति भावः ॥ **अवान्तरेति** । अपादानत्वादिनिमित्तभूतव्यापारविशेषविवक्षायामित्यर्थः ॥ अपादानस्यापि कञ्चित्कर्तृत्वं दर्शयति—**यथा मातेति** ॥ नन्वेवं करणत्वाद्यवस्थायामपि कर्तृत्वप्रसङ्गः प्रधानक्रियां प्रति साधनत्वाविशेषादित्यत आह—**कर्तृसंज्ञा त्विति** ॥ नन्वेवं कर्तृण्वुलन्तकारकसंज्ञापि तेषां न स्यादत आह—**कारकसंज्ञा त्विति** ॥ नन्वेवं करणादीनां विप्रतिषेधानुपपत्तिस्तद्व्यापाराणां परस्परपरिहारेण वर्तमानानामेकत्र युगपदसत्त्वादत आह—**यत्र च शक्तीनामिति** । करणत्वादीनामित्यर्थः ॥ **परत्वात्करणसंज्ञेति** । शक्तिद्वयस्यापि विप्रतिषेधसूत्रबलात्तृतीयैव वाचिकेति भावः ॥ नन्वेवं काष्ठानि पचन्तीति न स्यादत आह—**असिश्छिनत्तीति** । वस्तुतस्तदा स्वातन्त्र्यमेव विवक्षितमिति न परत्वोपयोगोऽन्यथा करणाकाङ्क्षैव न स्यात् स्वगतैकशक्त्यभिधाने स्वगतसकलशक्तीनामभिहितवत्प्रकाशान्न कदापि तृतीया तत्रेति कैयटाशयः ॥ छेदनस्य नियमेन करणाकाङ्क्षत्वात्तद्दर्शयति—**तदा त्विति** ॥ नन्वेकस्यैव कर्तृत्वकरणत्वे युगपद्विरुद्धे अत आह—**विवक्षेति** ॥ नन्वेवं परस्परं बाध्यबाधकत्वं कथमत आह—**वस्तुस्थित्या त्विति** ॥

(पक्षान्तरभाष्यम्)

अथ वा यावद् ब्रूयात्—'क्रियायाम्' इति, तावत्—'कारके' इति । एवं च कृत्वा निर्देश उपपन्नो भवति 'कारके' इति । इतरथा हि 'कारकेषु' इति ब्रूयात् ॥ कारके ॥ २३ ॥

(**प्रदीपः**) **अथ वेति** । क्रियात्र सूत्रे कारकशब्देनोच्यते । सा हि कर्त्रादीनि विशिष्टव्यपदेशयुक्तानि करोति । विषयत्वेन चायमधिकारः क्रियायां विषये यद् ध्रुवमित्यादि वस्तु संपद्यते ॥ **एवं च कृत्वेति** । निर्धारणसप्तम्यां हि कारकेष्विति वाच्यम् । निर्धारणस्यानेकाश्रयत्वात् । **कारकाद्दत्तश्रुतयो**रित्यादौ तु कारकशब्दस्य स्वरितत्वात्तदधिकारोपात्तानामपादानादीनां ग्रहणम् ॥ २३ ॥

(**उद्योतः**) ननु कारकशब्दाल्लोके क्रियाप्रतीतिर्न दृष्टेत्यत आह—**सूत्र इति** । सौत्रत्वादेकवचननपुंसकत्वे ॥ **विषयत्वेनेति** । विषयत्वं च जनकत्वमेव ॥ **वस्तु** वाक्यार्थः ॥ भाष्ये—**एवं च कृत्वेति** । पूर्वमते हि प्रथमोचितेति भावः ॥ ननु मास्तु संज्ञापक्षः कारकपदस्य क्रियापरत्वं च निर्धारणसप्तम्यानुपदोक्तार्थलाभादत आह—**इतरथा हीति** ॥ **कारकेष्वितीति** । **भिदचोन्त्यादि**त्यादिस्तु सौत्रः प्रयोगः । बहुवचनस्थाने एकवचनस्वीकारात् तत्रागत्या तथा स्वीकार इति भावस्तदाह—**निर्धारणस्येति** । कारकाणां मध्ये यद् ध्रुवं तदपादानमित्यादिक्रमेण हि तदर्थः । **द्वन्द्वः सामासिकस्य चे**ति त्वार्षम् । लोके तु निर्धारणस्थले एकवचनप्रयोगो न साधुरिति बोध्यम् ॥ नन्वेवं **कारकाद्दत्ते**त्यादौ क्रियाजनकमात्रस्य ग्रहणं स्यादत आह—**कारकाद्दत्तेति** ॥ २३ ॥

(अथापादानसंज्ञाप्रकरणम्)

(१७७ अपादानसंज्ञासूत्रम् ॥ १।४।३ आ. २ सू.)

२६४ ध्रुवमपायेऽपादानम् ॥ १।२४ ॥

(ध्रुवग्रहणप्रयोजनाधिकरणम्)

(अनुयोगभाष्यम्)

ध्रुवग्रहणं किमर्थम्?।

(प्रदीपः) **ध्रुवमपाये ॥ २४ ॥ ध्रुवग्रहणमिति।** अध्रुवस्य परत्वात्संज्ञान्तरं प्रवर्तिष्यते इति प्रश्नः ॥

(उद्द्योतः) **ध्रुवमपाये ॥ २४ ॥** अपायोत्र विभागजसंयोगानुकूलोऽवधिसाकाङ्क्षो गतिविशेषः ॥ **"गतिर्विना त्ववधिना नापाय इति कथ्यते"** इति ह्युक्तेः॥ नन्वध्रुवनिवृत्त्यर्थं तत्स्यादत आह—**अध्रुवस्येति** ॥

(समाधानभाष्यम्)

ग्रामादागच्छति शकटेन।

(प्रदीपः) **शकटेनेति।** अपाये शकटस्यापि साधनत्वादपादानसंज्ञा प्राप्नोति ॥

(उद्द्योतः) ननु शकटस्य विभागाश्रयत्वाभावात्कथं प्राप्तिरत आह—**अपाये इति।** अपाये यत्साधनमित्येव शब्दमर्यादया लभ्यते न त्वदुक्तमिति भावः ॥

(समाधानबाधकभाष्यम्)

नैतदस्ति। करणसंज्ञात्र बाधिका भविष्यति ॥

(प्रदीपः) **करणसंज्ञेति।** यथा धनुषा विध्यतीति क्रियमाणेपि ध्रुवग्रहणे परत्वात्करणसंज्ञा भवति एवमक्रियमाणेपि शकटस्य भविष्यतीत्यर्थः ॥

(समाधानान्तरभाष्यम्)

इदं तर्हि ग्रामादागच्छन्कंसपात्र्यां पाणिनौदनं भुङ्क्ते इति ॥

(प्रदीपः) **इदं तर्हीति।** ननु कंसपात्री साधनमेवागमने न भवति, भुजिक्रियायां तु साधनं ध्रुवा च। तत्र परत्वादधिकरणसंज्ञेति **आकडारसूत्र** उक्तम्। एवं तर्हि वस्तुस्थित्यात्रागमनं प्रधानं तदङ्गं तु भोजनम्। शब्दात्तु विपरीतो गुणप्रधानभावः प्रतीयते। तदुक्तं हरिणा—

चङ्क्रम्यमाणोधीष्वात्र जपंश्चङ्क्रमणं कुरु।
तादर्थ्यस्याविशेषेपि शब्दाद्भेदः प्रतीयते ॥

इति। तत्र कंसपात्री भुजेः साधनत्वात्तद्वारेणागमनस्यापि भवत्येव साधनम् ॥

(उद्द्योतः) भाष्ये—**ग्रामादागच्छन्निति।** ग्रामात्काशीमागच्छन् बलाधानाय मध्ये कंसपात्र्यामोदनं भुङ्क्ते इत्यर्थः ॥ **नन्विति।** न च भोजनद्वारा गमनसाधनत्वम्। भोजनस्य प्राधान्येन गमनाङ्गत्वाभावात्। एवं च पुनरत्र कथनमनुचितमिति भावः ॥ **वस्तुस्थित्येति।** भोजनस्यागमनोद्देश्यकत्वादार्थिकं प्राधान्यमिति भावः ॥ **जपंश्चङ्क्रमणं कुर्विति पाठः।** **अधीयंश्चङ्क्रमणमिति** पाठे इङ्धार्योः शत्रकृच्छ्रिणीति शतेत्यन्ये॥ **तादर्थ्यस्य।** चंक्रमणार्थित्वस्य॥ प्रेरकस्य हि गवादिरक्षणाय चङ्क्रमणमात्रमपेक्षितमिति तस्यैवार्थं प्राधान्यम् ॥ नन्वेवमपि भुजिसाधनकंसपात्र्याः कथमागमनसाधनत्वमत आह—**तत्रेति।** कंसपात्र्यधिकरणकभोजनस्य गमनोद्देशेन प्रवृत्तेरिति भावः ॥

(समाधानबाधकभाष्यम्)

अत्राप्यधिकरणसंज्ञा बाधिका भविष्यति ॥

(प्रदीपः) **अत्रापीति।** शब्देन भोजनस्यैव प्राधान्यं प्रतीयते इति तत्प्रयुक्तयैव संज्ञया भाव्यम्। यथा भोक्तुं ग्राममभिनिविशत इति प्रधानक्रियापेक्षया ग्रामस्य कर्मसंज्ञा भवति। न तु भुज्यपेक्षयाऽधिकरणसंज्ञा ॥

(उद्द्योतः) **शब्देनेति।** शब्दसंस्कारे तस्यैव प्रत्यासत्त्या ग्रहीतुमुचितत्वादिति भावः ॥

(समाधानान्तरभाष्यम्)

इदं तर्हि वृक्षस्य पर्णं पतति, कुड्यस्य पिण्डः पततीति ॥

(प्रदीपः) **वृक्षस्येति।** अस्त्यत्रापाय इति भावः ॥ नन्वत्र कारकत्वाभावात्संज्ञा न भविष्यति अपायाभावाच्च। सत्येव ह्यवधावपायो भवतीति पूर्वसूत्रे उक्तत्वात्॥ तत्र केचिदाहुः—सुज्ञानत्वात्पूर्वसूत्रे उक्तत्वाच्च भाष्यकारेणायमर्थो नोक्तः॥ अन्येत्वाहुः—सतीह ध्रुवग्रहणे विशिष्टोऽपायो लभ्यते, असति तु तस्मिन् पातमात्रस्य लोकेऽपायत्वेन प्रसिद्धत्वात्कारकाधिकारानपेक्षया च प्रत्युदाहरणमुपन्यस्तम् ॥

(उद्द्योतः) **सत्येवावधाविति।** विभागजसंयोगानुकूलव्यापार एवापायः, इह तु संयोगानुकूलव्यापार एवार्थ इति भावः ॥ **सुज्ञानत्वादिति।** एवं च संज्ञिनिर्देशस्य कारकाक्षिप्तेन सिद्धत्वाद् ध्रुवग्रहणं चिन्त्यप्रयोजनमिति भावः ॥ **सतीहेति।** ध्रुवत्वेनावधित्वेन विवक्षित इत्यर्थो भवतीति भावः ॥ इह त्ववयवित्वेन विवक्षा नावधित्वेनेति तात्पर्यम् ॥ **कारकाधिकारानपेक्षयेति।** वृक्षस्य पर्णेऽन्वये क्रियाजनकत्वाभावादिति भावः। वस्तुतः पर्णसंबन्धेपि वृक्षस्य पातजनकत्वं वास्तवमस्त्येवेति तदपेक्षायामपि न दोषः। न च **कारक** इति सूत्रे तद्व्यावर्त्यत्वेनेदमाशङ्क्य नात्रापायो **विवक्षित** इत्यादिभाष्यादपायपदव्यावर्त्यत्वमुक्तं तत्कथमत्र ध्रुवपदव्यावर्त्यत्वोक्तिर्ध्रुवपदेनाचलार्थकेन तद्व्यावृत्त्यसंभवश्चेति वाच्यम्। **ध्रुव इति किमर्थमित्यस्य ध्रुवमपाये इति किमर्थमि**त्याशयात्। तत्प्रश्नोक्तरीत्यैव चास्य व्यावृत्तिः। अपायजनकं यद् ध्रुवमचलं तदपादानमिति सूत्रार्थः। ध्रुवत्वं चावधित्वोपयोगिचेष्टानाश्रयत्वम्। तेनास्या-

बधित्वोपगमातिरिक्तस्वव्यापाराभावो ध्वन्यते । करणादौ तु तत्त्वोपगमातिरिक्तोपि स्वव्यापारोऽस्तीत्याहुः ॥

(शेषपूर्वधिकरणम्)

(१०८९ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ जुगुप्साविरामप्रमादार्थानामुपसंख्यानम् ॥ * ॥

(भाष्यम्) जुगुप्साविरामप्रमादार्थानामुपसंख्यानं कर्तव्यम् ॥ जुगुप्सा—अधर्माज्जुगुप्सते । अधर्माद्बीभत्सते ॥ विराम—धर्माद्विरमति । धर्मान्निवर्तते ॥ प्रमाद—धर्मात्प्रमाद्यति । धर्मान्मुह्यति ॥

इदं चोपसंख्यानं कर्तव्यम् । सांकाश्यकेभ्यः पाटलिपुत्रका अभिरूपतरा इति ॥

(प्रदीपः) जुगुप्सेति । संश्लेषपूर्वको विश्लेषोऽपायः स चात्र नास्ति । बुद्धिकल्पितस्तु गौण इति भावः ॥ कारकशेषत्वाच्चात्र षष्ठी प्राप्नोति यथा नटस्य शृणोतीति ॥ सांकाश्यकेभ्य इति । पञ्चमी विभक्ते इत्यनपेक्ष्य वचनम् । अत्र यतश्च निर्धारणमिति षष्ठीसप्तम्यौ प्राप्नुतः ॥

(उद्योतः) जुगुप्सा निन्दा । गौण इति । अपायत्वेनाप्रसिद्ध इत्यर्थः ॥

(तटस्थाक्षेपभाष्यम्)

तत्तर्हीदं बहु वक्तव्यम् ? ।

(वार्तिकप्रत्याख्यानभाष्यम्)

न वक्तव्यम् । इह तावद्—अधर्माज्जुगुप्सते अधर्माद्बीभत्सते इति । य एष मनुष्यः प्रेक्षापूर्वकारी भवति, स पश्यति दुःखो ऽधर्मो नानेन कृत्यमस्तीति । स बुद्ध्या संप्राप्य निवर्तते । तत्र "ध्रुवमपायेऽपादानम्" इत्येव सिद्धम् ॥

इह धर्माद्विरमति धर्मान्निवर्तते इति । धर्मात्प्रमाद्यति धर्मान्मुह्यतीति । इह य एष मनुष्यः संभिन्नबुद्धिर्भवति स पश्यति—नेदं किंचिद्धर्मो नाम नैनं करिष्यामीति स बुद्ध्या संप्राप्य निवर्तते । तत्र "ध्रुवमपाये ऽपादानम्" इत्येव सिद्धम् ॥

इह च सांकाश्यकेभ्यः पाटलिपुत्रका अभिरूपतरा इति यस्तैः साम्यं गतवान् भवति स एतत्प्रयुङ्क्ते ॥

(प्रदीपः) न वक्तव्यमिति । साधकतमं करणमिति तमग्रहणेन स्वरितेनाधिकार इत्यधिकः कारोधिकारइत्यस्यार्थस्याश्रयणेन च बुद्धिव्यवस्थितापायाश्रयाऽपादानसंज्ञा प्रवर्तते ॥ अधर्माज्जुगुप्सत इति । जुगुप्सादयो निवृत्त्यङ्गे जुगुप्सादौ वर्तन्ते ॥ संभिन्नबुद्धिरिति । धर्माधर्मयोरेकाकारबुद्धिर्नास्तिक इत्यर्थः ॥ यस्तैरिति । तैः सांकाश्यकैः पाटलिपुत्रकाणां समगुणत्वावः साम्यमवगतवान्स प्रकर्षाश्रयेण पुनः पृथक् कृत्वा वाक्यं प्रयुङ्क्ते इत्यर्थः ॥

त्रिविधं चेदमपादानम्—निर्दिष्टविषयमुपात्तविषयमपेक्षितक्रियं चेति । तत्र निर्दिष्टविषयम्—यत्र धातुनाऽपायलक्षणो विषयो निर्दिष्टः यथा—ग्रामादागच्छतीति ॥ उपात्तविषयम्—यत्र धातुर्धात्वन्तरार्थाङ्गं स्वार्थमाह । यथा बलाहकाद्विद्योतत इति । निःसरणाङ्गे द्योतनेत्र द्युतिर्वर्तते । यथा वा कुसूलात्पचतीत्यादौ आदानाङ्गे पाके पचिर्वर्तते ॥ अपेक्षितक्रियम्—यत्र क्रियावाचि पदं न श्रूयते केवलं क्रिया प्रतीयते । यथा—सांकाश्यकेभ्यः पाटलिपुत्रका अभिरूपतरा इति ।

(उद्योतः) तमग्रहणेनेति । कारकाधिकारादेव साधकत्वे लब्धे साधकग्रहणेनैव प्रकर्षे लब्धे तमग्रहणं व्यर्थं सदप्रसिद्धार्थकत्वेन गौणस्यापि ग्रहणं ज्ञापयतीत्यर्थः ॥ युक्त्यन्तरमप्याह—स्वरितेनाधीत्यादि ॥ ननु प्रयोक्तुस्तैः साम्याभावाद् यस्तैः साम्यं गतवानित्यनुपपन्नमत आह—तैरिति ॥ नन्वत्र क्रियाभावात्कारकत्वाभावेन कथमपादानत्वमत आह—त्रिविधं चेति ॥ केवलं प्रतीयतइति । अविश पिण्डीमित्यादाविवोपात्तपदेनेत्यर्थः ॥ यथेति । अत्र विभक्ता इति क्रिया गम्यत इत्याशयः ॥

(अनुपपत्तिपरिहाराधिकरणम्)

(१०९० आक्षेपवार्तिकम् ॥ २ ॥)

॥ * ॥ गतियुक्तेष्वपादानसंज्ञा नोपपद्यतेऽध्रुवत्वात् ॥ * ॥

(भाष्यम्) गतियुक्तेष्वपादानसंज्ञा नोपपद्यते । रथात्प्रवीतात्पतितः । अश्वात्त्रस्तात्पतितः । सार्थाद्गच्छतो हीन इति । किं कारणम् । अध्रुवत्वात् ॥

(प्रदीपः) गतियुक्तेष्विति । अचलं ध्रुवमेकरूपं चेति परिस्पन्दे ध्रुवता नास्तीति मन्यते ॥ अश्वात्त्रस्तादिति । त्रासपूर्वके परिस्पन्देऽनेकार्थत्वाद्धातूनां त्रसिर्वर्तते । त्रस्तश्चाश्वः पातस्य निमित्तमिति पूर्वमश्वस्य त्रस्तत्वेन संबन्धः पश्चात्पतित इत्यनेनेति ध्रुवताश्वस्य नास्ति ॥

(उद्योतः) गतियुक्तेष्विति । त्रासादीनामवधित्वोपयोगितां मन्यमानस्य प्रश्नः ॥ उत्तराशयस्तु—न तदवधित्वोपयोगि, अश्वात्पतितो वृक्षात्पतित इत्यादावभावात् । अत्र विद्यमानमपि तदविवक्षितत्वान्नावधित्वोपयोगितया विवक्षितम्, किं त्वश्वत्वादिकमेवेति तत्त्वम् ॥ ननु त्रासो नाम मनोधर्मो न हि तावता पिण्डस्य ध्रुवत्वमपैतीत्यत आह—त्रासपूर्वके इति ॥ ननु त्रासक्रियान्वयात्पूर्वमेव पतनक्रियासंबन्धे ध्रुवत्वमस्त्येवेत्यत आह—त्रस्तश्चाश्व इत्यादि ॥

(१०९१ समाधानवार्त्तिकम् ॥ २ ॥)

॥*॥ न वाऽध्रौव्यस्याविवक्षितत्वात् ॥*॥

(भाष्यम्) न वा एष दोषः । किं कारणम्?। अध्रौव्यस्याविवक्षितत्वात्। नात्राध्रौव्यं विवक्षितम् किं तर्हि?। ध्रौव्यम्। इह तावद्—अश्वात्त्रस्तात्पतित इति यत्तदश्वेऽश्वत्वमाशुगामित्वं, तद्ध्रुवं तच्च विवक्षितम् ॥

रथात्प्रवीतात्पतित इति यद्रथे रथत्वं रमन्तेऽस्मिन् रथ इति तद्ध्रुवं तच्च विवक्षितम् ॥

सार्थाद्गच्छतो हीन इति यस्तत्सार्थे सार्थत्वं सहार्थीभावः तद्ध्रुवं तच्च विवक्षितम् ॥

(प्रदीपः) **न वेति**। अयमर्थः—ध्रुवमेकरूपमुच्यते। तच्च ध्रौव्यमपायविषयमाश्रीयते। न त्वनवच्छिन्नम्। ततोऽपाये यदनाविष्टं तदपाये ध्रुवमुच्यते। देवदत्तकर्तृके च पाते त्रस्तस्याप्यश्वस्यापायानावेशाद् ध्रुवत्वम्। देवदत्तस्यैवापायावेशादध्रुवत्वम्। अथ वाश्वस्य त्रस्तत्वाद्यदध्रौव्यं तत्प्रथममविवक्षितमित्यर्थः। तथा हि - कारकस्य पूर्वं क्रियया समन्वयः। स च श्रुतिप्रापित उच्यते। पश्चाद्विशेषणेन वाक्यीयः संबन्धः। ततश्चाश्वात्पतित इति संबन्धे नास्त्यश्वस्याध्रुवत्वम्। पश्चात्त्रस्तत्वेन संबन्धे सत्यप्यध्रौव्येन्तरङ्गा संज्ञा न निवर्तते। विशेषणस्यासत्यप्यपादानत्वे सामयिकी विभक्तिः। सा च विशेष्यानुरोधेन प्रवर्तते न त्वनियमेन ॥ अथवा त्रस्तस्याप्यपादानत्वं सत्यपि त्रासापेक्षेऽध्रुवत्वे पातं प्रति ध्रुवत्वात्। यथोक्तं प्राक् ॥ **आशुगामित्वमिति**। अयमर्थः। व्युत्पत्तिमात्रमाशुगामित्वमिति तदपेक्षयाऽध्रौव्यं नशङ्कनीयम्। जातिरेव शब्दप्रवृत्तिनिमित्तमिति नास्त्यत्राध्रौव्यम् ॥ आशुगामित्वशब्देनैकार्थसमवायात्साहचर्यादश्वत्वमेवोच्यते ॥

(उद्योतः) **एकरूपमिति**। ध्रुवमस्य शीलमित्यादिदर्शनाद् **ध्रुव स्थैर्ये** इत्यादिधात्वर्थानुसाराच्चेति भावः ॥ **अपायविषयमिति**। प्रत्यासत्तेरिति भावः ॥ विभागजसंयोगानुकूलो गतिविशेषो ह्यपायः। स च प्रधान एव गृह्यते युक्तत्वात् स चात्र पत्युपात्तः। न च तदाश्रयोऽश्वस्तथात्वे कर्तृत्वापत्तिरिति भावः ॥ **अनवच्छिन्नमिति**। अनिरूपितमित्यर्थः ॥ **अपाये यदनाविष्टमिति**। अपाये सति प्रकृतधातूपात्तया क्रियया यदनाविष्टमित्यर्थः। एवं च प्रकृतधातूपात्तगत्यनाविष्टत्वमेव ध्रुवत्वमिति तात्पर्यम् ॥ हरिरप्याह—**अपाये यदुदासीनं चलं वा यदि वाऽचलम्। ध्रुवमेवातदावेशा**दिति॥ परं तु सिद्धान्तभाष्याक्षराणामत्रार्थे न सामञ्जस्यं **किं तर्हि ध्रौव्यं** विवक्षितम्। अश्वात्त्रस्तात्पतित इत्यत्राश्वत्वं ध्रुवं तदेव विवक्षितम् धावतः पतित इत्यादौ सतोऽप्यध्रौव्यस्याविवक्षेत्यक्षराणामसामञ्जस्यात्। प्रधानव्यापाराश्रयत्वरूपस्य त्वदभिमताध्रौव्यस्यात्र कदाप्यसत्त्वात्। तस्मान्मदुक्त एवं सूत्रार्थ उचितो भाष्यार्थश्चेति सुधियो विभावयन्तु ॥ **कारकस्य पूर्वमिति**। क्रियानिर्वर्तकरूपस्य तस्यान्तरङ्गत्वात्पूर्वं क्रिययाऽन्वय इत्यर्थः। श्रुतिः, पञ्चम्यादिः। **वाक्यं**, पदसमूहः। पूर्वमश्वात्पतित इति बोधे पातहेत्वाकाङ्क्षायां पश्चात् त्रस्तादित्यस्यान्वय इति भावः ॥ नन्वेवमपि त्रस्तादिति पञ्चम्यनुपपन्नैवेत्यत आह—**विशेषणस्येति**॥ **सामयिकीति**। न **केवला प्रकृति**रिति समयाद्विभक्तिरुत्पाद्या। सा चाभिन्नविशेष्यसमानशक्तिकत्वनियमाद्विशेषणानां तेभ्यो विशेष्यसमानैव विभक्तिरिति भावः ॥ आद्यपक्षस्यैव युक्तत्वबोधनाय पुनस्तं स्मारयति—**अथ वेति**। भाष्यस्वारस्यं द्वितीयव्याख्याने एव ॥ **न शङ्कनीयमिति** ॥ पूर्वोक्तद्वितीयव्याख्यारीत्येयं शङ्का बोध्या, त्रस्तत्वस्य प्रथममनन्वयेप्याशुगामित्वस्य शब्दादुपस्थित्या तत्कृतमध्रौव्यं न शङ्क्यं जातेरेव प्रवृत्तिनिमित्तत्वादिति भावः ॥ भाष्ये—**सहार्थीभाव इति**। सहार्थो येषां तद्भाव इत्यर्थः ॥ परे त्वाशुगमनाश्रयत्वमश्वशब्देन योगतो बुध्यते रमणक्रियाश्रयत्वं रथशब्देनोच्यते सहमिलनक्रियाश्रयत्वं च सार्थशब्देन। अश्वत्वादिकं च रूढ्या। एवं चाश्वात्पतित इति प्रयोगे यद्यश्वस्य तदविवक्षयाऽश्वत्वमात्रविवक्षया ध्रुवत्वं तवाभिमतं तर्हि त्रस्तादिति विशेषणेपि न क्षतिरिति भावः। अश्वनिष्ठाश्वत्वाशुगामित्वयोर्मध्ये तदश्वत्वमेव ध्रुवताप्रयोजकं **तच्च विवक्षितं** तदेव विवक्षितमित्यक्षरार्थ इत्याहुः॥

(आक्षेपभाष्यम्)

यद्यपि तावदत्रैतच्छक्यते वक्तुम्। ये त्वेतेत्यन्तं गतियुक्तास्तत्र कथम्। धावतः पतितस्त्वरमाणात्पतित इति ॥

(प्रदीपः) **यद्यपीति**। यत्र क्रिया न प्रवृत्तिनिमित्तं किं तु व्युत्पत्तिमात्रनिमित्तं तत्रैतद्वक्तुं युज्यते। यत्र तु शब्दप्रवृत्तिनिमित्तं क्रिया तत्र कथं नाध्रौव्यमिति प्रश्नः ॥

(समाधानभाष्यम्)

अत्रापि—* न वाऽध्रौव्यस्याविवक्षितत्वाद् * इत्येव? ॥

कथं पुनः सतो नामाविवक्षा स्यात्? ॥

सतोप्यविवक्षा भवति। तद्यथा—'अलोमिका एडका'। अनुदरा कन्येति ॥ असतश्च विवक्षा भवति—समुद्रः कुण्डिका' 'विन्ध्यो वर्धितकमिति ॥ ध्रुवमपायेऽपादानम् ॥ २४ ॥

(प्रदीपः) **अत्रापीति**। सरणक्रियोपलक्षितं द्रव्यमात्रमपादानत्वेन विवक्षितम्। तच्च देवदत्तकर्तृके पाते पूर्वोक्तन्यायाद् ध्रुवमेवेत्यर्थः ॥ **कथं पुनरिति**। शब्दोपात्तमपि सरणं द्रव्योपलक्षणार्थत्वादध्रौव्यनिमित्तं न भवतीति कुत एतदिति प्रश्नः ॥ **अलोमिकेति**। अल्पत्वाल्लोम्नां तत्कार्याकरणादेवमुच्यते ॥ **असतश्चेति**। निदर्शनार्थमिदमुच्यते। यथाऽसतो विवक्षा भवति एवं सतोप्यविवक्षेत्यर्थः ॥ **समुद्रः**

कुण्डिकेति । कुण्डिकायां पानीयबाहुल्यात्समुद्रत्वं विवक्षितं समुद्रस्य वा सुतरत्वात्कुण्डिकात्वम् ॥ **विन्ध्यो वर्द्धितकमिति** । पूर्ववदन्यतररूपारोपेण व्याख्येयम् । मेषो मेषादपसर्पतीत्यत्रैकस्य कर्तृत्वविवक्षापरस्यापादानत्वविवक्षा ॥ यदा तु मेषावपसरत इति प्रयोगस्तदाऽवध्यन्तरमपेक्षणीयम् ॥ २४ ॥

(**उद्द्योतः**) ननु प्रवृत्तिनिमित्तमविवक्षितमित्ययुक्तमत आह— **सरणक्रियोपलक्षितमिति** । अनेन प्रवृत्तिनिमित्तस्याप्यविवक्षा दर्शिता ॥ तदेव भाष्ये उक्तं **सतोप्यविवक्षेति** ॥ **पूर्वोक्तेति**। त्रस्तादित्यादावुक्तरीत्येत्यर्थः ॥ नन्वसतश्चेति प्रकृतानुपयुक्तमत आह—**निदर्शनार्थमिति** । अग्रे सूक्ष्मो मूले स्थूल ओदनपिण्डो **वर्द्धितकम्** ॥ **यदा त्विति** । परस्परस्मान्मेषावपसरत इत्यत्र तु

मेषान्तरक्रियापेक्षमवधित्वं पृथक् पृथग् ।
मेषयोः स्वक्रियापेक्षं कर्तृत्वं च पृथक् पृथग् ॥

इति बोध्यम् । किं च मेषपदोपात्तयोरेव क्रियाश्रयत्वं परस्परपदोपात्तयोर्विभागाश्रयत्वमेवेति तत्र न दोषः । अन्यथा वस्तुतस्तदाश्रयक्रियाभेदेऽपि धातुना विभागद्वयस्य तज्जनकक्रियाद्वयस्य च निवृत्तभेदस्यैवोपादानातपरत्वात्कर्तृत्वं दुर्वारमेव स्यात् । आत्मानमात्मनेत्यादावन्तःकरणाद्युपाधिना भेदस्येव शब्दरूपोपाधिकृतभेदस्यात्रापि सत्त्वाच्च ॥ असन्मते शब्दानुविद्धार्थस्यैव भानाच्च ॥ हरिकारिकायामप्यवधित्वमित्यस्य परस्परपदोपात्तयोरिति शेषः । कर्तृत्वमित्यस्य मेषपदोपात्तयोरिति शेष इति वदन्ति ॥ २४ ॥

(१७८ अपादानसंज्ञासूत्रम् ।१।४ । ३आ. ३ सू.)

२६५ भीत्रार्थानां भयहेतुः ॥१।४।२५॥

(प्रत्याख्यानाधिकरणम्)

(प्रत्याख्यानभाष्यम्)

अयं योगः शक्योऽवक्तुम् ॥

(आक्षेपभाष्यम्)

कथं वृकेभ्यो बिभेति दस्युभ्यो बिभेति चोरेभ्यस्त्रायते दस्युभ्यस्त्रायत इति ? ॥

(प्रदीपः) **भीत्रार्थानाम्** ॥ २५ ॥ **कथमिति** । भयमाकुलीभावः, त्राणमनर्थप्रतिघात इति । तत्र च नास्ति मुख्योऽपाय इति प्रश्नः ॥

(**उद्द्योतः**) **भीत्रार्थानां** ॥ २५ ॥ सूत्रे भीत्राशब्दौ भावकिबन्तौ ॥ **चोरेभ्य** इति पाठे प्रज्ञाद्यणन्तो बोध्यः । चुरा स्तेयं शीलमस्येति णान्तो वा ॥ **अनर्थप्रतिघात इति** । अनर्थश्च भयं तद्धेतुश्चोर इति त्राणार्थानामपि भयहेतुः कारकं संभवतीति बोध्यम् ॥

(आक्षेपबाधकभाष्यम्)

इह तावद्-वृकेभ्यो बिभेति दस्युभ्यो बिभेतीति। य एष मनुष्यः प्रेक्षापूर्वकारी भवति । स पश्यति-यदि मां वृकाः पश्यन्ति ध्रुवो मे मृत्युरिति । स बुद्ध्या संप्राप्य निवर्तते, तत्र "ध्रुवमपायेपादानम्" इत्येव सिद्धम् ॥

इह चौरेभ्यस्त्रायते दस्युभ्यस्त्रायत इति, य एष मनुष्यः प्रेक्षापूर्वकारी सुहृद्भवति । स पश्यति-यदीमं चोराः पश्यन्ति ध्रुवमस्य वधबन्धनादिपरिक्लेशा इति । स बुद्ध्या संप्राप्य निवर्तयति । तत्र "ध्रुवमपायेपादानम्" इत्येव सिद्धम् ॥ भीत्रार्थानाम् ॥ २५ ॥

(प्रदीपः) **प्रेक्षापूर्वकारीति** । बुद्धिव्यवस्थापितोत्रापायोऽस्तीति भावः । तत्र निवृत्त्यङ्गे भये बिभेत्यादयो वर्तन्त इत्युपात्तविषयमेतदपादानम् । **चोरेभ्यस्त्रायत**इत्यनर्थपरिहाराय निवर्तयतीत्यर्थः । चोरमध्यगतस्यापि त्राणे चोरसंपर्कफलस्य वधबन्धनापहरणादेर्निवर्तनात्तेभ्यो निवर्तयतीत्युच्यते । **वारणार्थानामीप्सित** इत्यनेनात्रापादानसंज्ञा न प्राप्नोति चोराणामनीप्सितत्वात् । सूत्रारम्भपक्षे तु कारकशेषत्वात् षष्ठ्यां प्राप्तायामिदं वचनम् ॥ २५ ॥

(**उद्द्योतः**) भाष्ये—**पश्यति** । विचारयतीत्यर्थः ॥ ननु निवृत्तेरेव वारणत्वाद्वारणार्थाना**मित्यनेन सिद्धिरिति कुतो नोक्तमत आह—**वारणार्थानामिति** ॥ **अनीप्सितत्वात्** । तद्धात्वर्थप्रयोज्यफलानाश्रयत्वात् ॥ **इदं वचनमिति** । प्रत्याख्याने तु षष्ठ्या अनभिधानान्निवृत्तिर्बोध्या । क्रियां प्रति जनकत्वेन विवक्षायामेषा संज्ञा । संबन्धित्वेन विवक्षायां तु षष्ठ्यामिष्टापत्तिरेव । सूत्राणि प्रपञ्चार्थान्येवेति हरयः ॥ २५ ॥

(१७९ अपादानसंज्ञासूत्रम् ॥ १ । ४ । ३ आ. ४ सू०)

२६६ पराजेरसोढः ॥ १ । ४ । २६ ॥

(प्रत्याख्यानाधिकरणम्)

(प्रत्याख्यानभाष्यम्)

अयमपि योगः शक्योऽवक्तुम् ॥

(आक्षेपभाष्यम्)

कथम्—अध्ययनात्पराजयते इति ? ॥

(प्रदीपः) **पराजे** ॥२६॥ पराजिः क्वचिदभिभवे वर्तते । यथा शत्रून्पराजयते इति । इह त्वसोढग्रहणाद्ग्लानीभाववृत्तिर्गृह्यते । **अध्ययनात्पराजयते** हसति । अध्येतुं ग्लायतीत्यर्थः । अत्रचार्थेऽकर्मकत्वात्षष्ठ्यां प्राप्तायां वचनम् ॥

(**उद्द्योतः**) **पराजेर** ॥ २६ ॥ **असोढग्रहणादिति** । अत्र कालोऽविवक्षितः । तेन पराजेष्यत इत्यपि भवति ॥ **ग्लानीभावेति** । शक्तिवैकल्येत्यर्थः । **षष्ठ्यामिति** । तत्सम्बन्धिशक्तिवैकल्यमित्यर्थादिति भावः ॥

(आक्षेपबाधकभाष्यम्)

य एष मनुष्यः प्रेक्षापूर्वकारी भवति, स पश्यति दुःखमध्ययनं दुर्धरं च, गुरवश्च दुरुपचारा इति, स बुद्ध्या संप्राप्य निवर्तते। तत्र "ध्रुवमपायेऽपादानम्" इत्येव सिद्धम् ॥ पराजेरसोढः ॥ २६ ॥

(प्रदीपः) पूर्ववदस्यापि प्रत्याख्यानं निवृत्त्यङ्गे पराजये पराजेर्वर्तनात् ॥ २६ ॥

(उद्द्योतः) निवृत्त्यङ्गे इति । षष्ठीसमासः । शक्तिवैकल्येन ततो निवर्तत इत्यर्थात् ॥ २६ ॥

(१८० अपादानसंज्ञासूत्रम् ॥ १।४।३ आ० ५ सू०)

२६७ वारणार्थानामीप्सितः ॥ २७ ॥

(उदाहरणनिर्णयाधिकरणम्)

(आक्षेपभाष्यम्)

किमुदाहरणम् ? ॥

(प्रदीपः) **वारणार्थानाम्** ॥ २७ ॥ **किमुदाहरणमिति** । अव्याप्तिं मन्यमानस्य प्रश्नः ॥

(समाधानभाष्यम्)

माषेभ्यो गा वारयति ॥

(समाधानबाधकभाष्यम्)

भवेद्यस्य माषा, न गावस्तस्य माषा ईप्सिताः स्युः । यस्य तु खलु गावो, न माषाः; कथं तस्य माषा ईप्सिताः स्युः ॥

(प्रदीपः) **भवेद्यस्येति** । यस्यात्मीया माषास्तस्य त ईप्सिता इत्यर्थः । अभिप्रेतपर्यायमीप्सितशब्दं मन्यते ॥ **यस्य त्विति** । यस्यात्मीया गावः परकीयास्तु माषास्तस्य न त ईप्सिताः ॥

(उद्द्योतः) **वारणार्थो** ॥ २७ ॥ अव्याप्त्युपपादकं—**यस्य खल्विति** । भाष्ये ॥ ननु धात्वर्थजन्यफलशालित्वरूपमीप्सितत्वं सर्वत्राप्यस्तीत्यत आह—**अभिप्रेति** ॥

(समाधानसाधकभाष्यम्)

तस्यापि माषा एवेप्सिताः ॥ आतश्चेप्सिताः, यदेभ्यो गा वारयति ॥

(प्रदीपः) **तस्यापीति** । ईप्सितशब्दः क्रियाशब्द आश्रीयते न तु रूढिशब्दः । तत्र वारणक्रियया परकीया अपि माषा वारयितुराप्तुमिष्टा भवन्ति मा नशन्नेते इत्येतेभ्योसौ गा वारयति ॥ **माषा एवेति** । एवकारो भिन्नक्रमः । ईप्सिता एवेत्यर्थः ॥

(उद्द्योतः) **आप्तुमिष्टा इति** । **वारणं** प्रवृत्तिविघातः । स च तद्व्यापारजन्यतत्फलाभावप्रयोजको भक्षणादिजनकव्यापाराभावानुकूलोव्यापारः क्वचित्, क्वचित्तद्व्यापारजन्यतत्फलाभावप्रयोजकः संयोगानुकूलव्यापाराभावानुकूलव्यापारः ॥ एवं च तद्धात्वर्थप्रयोज्यफलाश्रया इत्यर्थस्तदाह—**मा नशन्निति** । नाशाभावरूपफलेन व्याप्तुमिष्टा इत्यर्थः । नाशाभावश्च भक्ष्यमाणाभावपर्यवसन्नस्तस्य च फलस्य धात्वर्थत्वपर्यन्तं नाग्रहः । माषनाशे हि सति राजभयमधर्मश्च स्यादिति भावः ॥ नन्वेवं **माषा एवेति** भाष्याद्गवामीप्सितत्वाभावो लभ्यते इति सुतरामीप्सिततमत्वाभावेन कर्मत्वाभावाद्द्वितीया न स्यादत आह—**भिन्नक्रम इति** । गवादिनिष्ठव्यापाराभावस्यैव मुख्यतयोद्देश्यत्वेन तदाश्रयत्वेनेच्छाविषयत्वात्तासां कर्मत्वमिति भावः ॥

(अनुपपत्तिपरिहाराधिकरणम्)

(आक्षेपभाष्यम्)

इह कूपादन्धं वारयतीति कूपेऽपादानसंज्ञा न प्राप्नोति । नहि तस्य कूप ईप्सितः । कस्तर्हि ? । अन्धः ॥

(प्रदीपः) **कूपादिति** । अन्धसंबन्धे कूपस्य न विनाशो नापि राजभयमिति प्रश्नः ॥ **कस्तर्ह्यन्ध इति** । तं प्रत्यनुकम्पायाः सद्भावात्तस्येप्सितत्वं मन्यते ॥

(उद्द्योतः) ननु पूर्वोदाहरणादस्य को विशेष इत्यत आह—**अन्धेति** ॥ ननु तदसंबन्धिनस्तस्य कथं तदीप्सितत्वमत आह—**तं प्रतीति** ॥

(समाधानभाष्यम्)

तस्यापि कूप एवेप्सितः । पश्यत्ययम्—अन्धः कूपं मा प्रापदिति ॥ अथ वा यथैवास्यान्यत्रापश्यत ईप्सा एवं कूपेऽपि ॥

(प्रदीपः) **तस्यापीति** । वारणक्रिययाप्तुमिष्ट इत्यर्थः ॥ **अथ वेति** । ईप्सित इत्यनेन कर्मणा कर्तृमात्रस्याक्षेपान्निवार्यमाणस्यान्धस्य गमनादिक्रियया कूप आप्तुमिष्टो भवतीति प्रवर्ततेऽपादानसंज्ञा । अन्धस्य च प्रवृत्त्यनुमेयेप्सा तदाह—**अन्यत्रापश्यत इति** । अन्धस्येत्यर्थः । स ह्यपश्यन्नपि गन्तव्यं जिगमिषति । अन्यथा न क्वचित्तस्य प्रवृत्तिः स्यात् ॥

(उद्द्योतः) माषाणां राजभयादितो नाशाभावरूपफलाश्रयत्वेन गोस्वाम्यभिप्रेतत्वेप्यस्य कथं तत्त्वमत आह—**वारणक्रियेति** । क्रियाशब्दस्य ग्रहणात् कूपस्यापि तत्संयोगाभावरूपफलाश्रयत्वादिति भावः ॥ **गमनादिक्रिययेति** । वारणधात्वर्थघटकयेत्यर्थः । अत्र पक्षे भक्षणादिजनकव्यापाराभावानुकूलव्यापार एव वारयतेरर्थः । एवं च वारणार्थकधातुप्रतिपाद्यव्यापारजन्यफलाश्रयत्वमेवात्रेप्सितत्वमिति भावः ॥ नन्वेवमपि प्रधानकर्तुरनीप्सितत्वात्कथमेतत्प्राप्तिरत उक्तं **कर्तृमात्रस्येति** । कर्तृग्रहणं चोपलक्षणम् ॥ नन्वन्धस्य पदार्थज्ञानाभावात्कथं तद्विषयेप्सेत्यत आह—**अन्धस्येति** ॥

(आपत्तिपरिहाराधिकरणम्)

(आक्षेपभाष्यम्)

इहाग्नेर्माणवकं वारयतीति माणवकेऽपादानसंज्ञा प्राप्नोति ॥

(प्रदीपः) इदानीमतिप्रसङ्गमुद्भावयति—**इहाग्नेरिति** ॥

(समाधानभाष्यम्)

कर्मसंज्ञात्र बाधिका भविष्यति ॥

(प्रदीपः) **कर्मसंज्ञात्रेति** । परत्वादिति भावः । कर्मसंज्ञाया अवकाशो वारणार्थेभ्योऽन्ये धातवः । अपादानसंज्ञायास्तु प्रकर्षरहितमीप्सितम् । ईप्सिततमस्य तूभयप्रसङ्गे परत्वात्कर्मसंज्ञा ॥

(आक्षेपभाष्यम्)

अग्नावपि तर्हि बाधिका स्यात् । तस्माद्वक्तव्यम् "कर्मणो यदीप्सितम्" इति । "ईप्सितेप्सितम्" इति वा ॥

(प्रदीपः) **अग्नावपीति** । कारकाधिकारे प्रकर्षो न विवक्ष्यते इत्यतत्रं तमनिर्देशं मन्यते ॥ **कर्मणो यदीप्सितमिति** । तत्र कर्मसंज्ञा निमित्तमेवापादानसंज्ञाया इति माणवके प्रवर्तते । ततस्तस्येप्सितस्याग्नेरपादानसंज्ञेत्यर्थः ॥ **ईप्सितेप्सितमिति** । वारयितुर्यदीप्सितं कर्म तस्य यदीप्सितमित्यर्थः । शेषषष्ठ्या चात्र समासः । अन्यथा **केन च पूजायामिति** निषेधः स्यात् ॥

(उद्द्योतः) सामर्थ्यगम्यस्यैव प्रकर्षस्यानाश्रयणं न तूपात्तस्येत्यत उक्तम्—**मन्यत इति** । नन्वीप्सितमाषाणां न गवादीप्सितं नापि तस्यापादानत्वमिष्टमत आह—**वारयितुरिति** ॥ **यदीप्सितं कर्मेति** । कर्मशब्दोऽत्र क्रियापरः । ईप्सितो यो धात्वर्थ इत्यर्थः ॥ **तस्य यदीप्सितमिति** । तज्जन्यफलाश्रय इत्यर्थः । भक्षणादिजनकव्यापाराभावस्य हि नाशाभावान्धापतनादि फलमिति भावः ॥ एवं च पूर्वोक्तसमाधानद्वयाभिप्रायकं लक्षणद्वयं बोध्यम् । एतेनार्थाभेदाच्छब्दभेदमात्रेण लक्षणद्वयकथनमयुक्तमित्यपास्तम् ॥

(१०९२ समाधानवार्तिकम् ॥ १ ॥)

॥ * ॥ वारणार्थेषु कर्मग्रहणानर्थक्यं कर्तुरीप्सिततमं कर्मेति वचनात् ॥*॥

(भाष्यम्) **वारणार्थेषु कर्मग्रहणमनर्थकम् । किं कारणम्? । कर्तुरीप्सिततमं कर्मेति वचनात् । "कर्तुरीप्सिततमं कर्म" इत्येव सिद्धम् ॥**

(प्रदीपः) **कर्तुरिति** । प्रकर्षप्रत्ययोपादानसामर्थ्यात्कर्मसंज्ञायां प्रकर्षो विवक्ष्यत एव । तत्र द्वयोः संज्ञयोः सावकाशयोः परत्वादीप्सिततमस्य कर्मसंज्ञा ॥ २७ ॥

(उद्द्योतः) ननु प्रकर्षाविवक्षणेनानवकाशत्वादिदमेव भविष्यतीत्यत आह—**प्रकर्षेति** । अयं भावः—तरबादिः प्रवृत्तिनिमित्तगतप्रकर्षे विधीयते । प्रवृत्तिनिमित्तं चात्रेच्छा तस्यां स्वतः प्रकर्षसंभवेपि व्याख्यानाद्विशेषणीभूतव्याप्तिगतः स गृह्यते । व्याप्तिप्रकर्षश्च प्रकृतधात्वर्थप्रधानीभूतव्यापारप्रयोज्यधात्वर्थफलीयत्वरूपः ॥ एवं च प्रकृतधात्वर्थप्रधानीभूतव्यापारप्रयोज्यधात्वर्थफलाश्रयत्वमीप्सिततमत्वम् । तच्च नाग्नाविति ॥ ननु कर्तृग्रहणात्सिद्धमेतत् प्रकृतसूत्रे इवेप्सितेति कर्मणा कर्तुराक्षेपेणैव सिद्धे पुनः कर्तृग्रहणेन प्रकृतधात्वर्थप्रधानीभूतव्यापाराश्रयस्यैव ग्रहणादिति चेन्न । लघुना तमग्रहणेन कर्तुरित्यस्य प्रत्याख्याने तात्पर्यादित्याहुः ॥

(सूत्रप्रत्याख्यानाधिकरणम्)

(प्रत्याख्यानभाष्यम्)

अयमपि योगः शक्योऽवक्तुम् ॥

(आक्षेपभाष्यम्)

कथं माषेभ्यो गा वारयतीति? ॥

(समाधानभाष्यम्)

पश्यत्ययं यदीमा गावस्तत्र गच्छन्ति ध्रुवः सस्यविनाशः, सस्यविनाशेऽधर्मश्चैव राजभयं च । स बुद्ध्या सम्प्राप्य निवर्तयति तत्र "ध्रुवमपायेऽपादानम्" इत्येव सिद्धम् ॥ वारणार्थानामीप्सितः॥२७

(उद्द्योतः) भाष्ये—**पश्यत्ययमिति** । विचारयतीत्यर्थः॥२७

(१८१ अपादानसंज्ञासूत्रम् ॥ १ । ४ । ३ आ. ६ सू.)

२६८ अन्तर्द्धौ येनादर्शनमिच्छति ॥ १ । ४ । २८ ॥

(उद्द्योतः) अन्तर्द्धौ ॥ २८ ॥ अन्तर्द्धिर्व्यवधानं यस्य च भावेनेतिसप्तमी । येनेति सौत्री तृतीया । उभयोः प्रयोगाभावेनोभयप्राप्तावित्यस्याप्रवृत्तेः । उभयप्रयोगे एव तत्प्रवृत्तिरित्यात्ममान इतिसूत्रे भाष्ये स्पष्टम् । अन्तर्द्धिनिमित्तकं यत्कर्तृकमात्मकर्मकादर्शनमिच्छति तदपादानमित्यर्थः ॥

(प्रत्याख्यानाधिकरणम्)

(प्रत्याख्यानभाष्यम्)

अयमपि योगः शक्योऽवक्तुम् ॥

(आक्षेपभाष्यम्)

कथम्—उपाध्यायादन्तर्धत्त इति? ॥

(प्रदीपः) **अन्तर्द्धौ येनादर्शनमिच्छति ॥ २८ ॥ अन्तर्धत्ते इति** । तिरोभवतीत्यर्थः ॥

(उद्द्योतः) नन्वन्तर्धत्त इत्यस्य विभजत इत्यर्थेऽपादानत्वं सिध्यतीत्यत आह—**तिरोभवतीति** । आत्मकर्मकोपाध्यायकर्तृकदर्शनाभावेच्छया तिरोभवतीत्यर्थः ॥

(समाधानभाष्यम्)

पश्यत्ययं 'यदि मामुपाध्यायः पश्यति ध्रुवं मे प्रेषणमुपालम्भो वेति, स बुद्ध्या सम्प्राप्य निवर्तते तत्र "ध्रुवमपायेऽपादानम्" इत्येव सिद्धम् ॥ अन्तर्धौ येनादर्शनमिच्छति ॥ २८ ॥

(उद्द्योतः) निवृत्तिपूर्वकतिरोभवने धातोर्वृत्तेर्ध्रुवमिति सूत्रेणैव सिद्धमिति बोध्यम् ॥ २८ ॥

(१८२ अपादानसंज्ञासूत्रम् ॥ १।४।३ आ. ७ सू.)

२६९ आख्यातोपयोगे ॥ १। ४।२९॥

(पदकृत्यकथनाधिकरणम्)

(अनुयोगभाष्यम्)

उपयोग इति किमर्थम् ?॥

(प्रदीपः) आख्यातोपयोगे ॥ २९ ॥ उपयोगो व्यापारः स चाविशिष्टो नटोपाध्याययोरिति मत्वा पृच्छति— **उपयोग इति किमर्थमिति ॥**

(उद्द्योतः) आख्यातोप ॥ २९ ॥ व्यापार इति । उपयुज्यते फलायेति व्युत्पत्तेरिति भावः ॥

(समाधानभाष्यम्)

नटस्य शृणोति, ग्रन्थिकस्य, शृणोति ॥

(समाधानबाधकभाष्यम्)

उपयोग इत्यप्युच्यमानेऽत्र प्राप्नोति । एषोपि ह्युपयोगः । अतिश्चोपयोगः ॥ यदारम्भका रङ्गं गच्छन्ति नटस्य श्रोष्यामः ग्रन्थिकस्य श्रोष्याम इति ॥

(प्रदीपः) **आरम्भका रङ्गं गच्छन्तीति** । रङ्गं सामाजिकस्थानम् । **आरम्भका** यत्नेन प्रवृत्तिमन्तो गच्छन्तीत्यर्थः ॥

(उद्द्योतः) आरम्भकाः । गीतश्रोतॄणां मध्ये मुख्याः । **यत्नेन प्रवृत्तिमन्तो गच्छन्तीति** । अत्यावश्यकत्वबुद्ध्या गच्छन्तीति यावत् । प्रवृत्तिरत्र व्यापारसामान्यं यत्नेनेत्यस्यातियत्नेनेत्यर्थः ॥

(समाधानसाधकभाष्यम्)

एवं तर्ह्युपयोग इत्युच्यते । सर्वश्चोपयोगः । तत्र प्रकर्षगतिर्विज्ञास्यते साधीयो य उपयोग इति । कश्च साधीयः? । यो ग्रन्थार्थयोः ॥

(प्रदीपः) **प्रकर्षगतिरिति** । व्यापारमात्रे लब्धे उपयोगग्रहणं विशिष्टव्यापारपरिग्रहार्थम् । तेन ग्रन्थार्थधारणार्थं यद्ग्रहणं स उपयोगः ॥

(उद्द्योतः) व्यापारमात्रे इति । कारकाधिकारादिति भावः ॥ ग्रन्थार्थधारणार्थमिति । यदा तु नटादिभ्योपि तथाध्ययनं तदा नटाच्छृणोतीति भवत्येवेति बोध्यम् ॥

(समाधानान्तरभाष्यम्)

अथ वा उपयोगः को भवितुमर्हति? ॥ यो नियमपूर्वकः । तद्यथा—उपयुक्ता माणवका इत्युच्यन्ते य एते नियमपूर्वकमधीतवन्तो भवन्ति ॥

(प्रदीपः) **अथ वेति** । उपयोगशब्दस्यैवायमर्थो नियमपूर्वकं विद्याग्रहणम् ॥

(उद्द्योतः) **अयमर्थ इति** । उपयोगशब्दस्य तत्रैव रूढिरन्यत्र तु लक्षणया प्रयोग इत्यर्थः । **नियमो** भिक्षाचरणभूशय्यादिः । इदं च तत्तद्विद्याश्रवणनियमानामुपलक्षणमित्याहुः ॥

(अनुपयोगेआख्यातुःकारकत्वनिर्णयाधिकरणम्)

(आक्षेपभाष्यम्)

किं पुनराख्यातानुपयोगे कारकमाहोस्विदकारकम्? ॥

(प्रदीपः) **किं पुनरिति** । उभयथा संभवाद्दोषदर्शनाच्च प्रश्नः ॥

(उद्द्योतः) **उभयथेति** । नटं विना गीतश्रवणाद्ययोगात्तस्य तज्जनकतया कारकत्वं कुलालपितृवदन्यथासिद्धत्वसम्भावनया चाकारकत्वमिति भावः ॥

(प्रत्याक्षेपभाष्यम्)

कश्चात्र विशेषः? ॥

(१०९३ कारकत्वदूषणवार्तिकम् ॥ १ ॥)

॥ * ॥ आख्यातानुपयोगे कारकमिति चेदकथितत्वात्कर्मसंज्ञाप्रसङ्गः ॥ * ॥

(भाष्यम्) **आख्यातानुपयोगे कारकमिति चेदकथितत्वात्कर्मसंज्ञा प्राप्नोति ॥**

(उद्द्योतः) भाष्ये—**अनुपयोगे इति** । अनियमपूर्वकश्रवणे इत्यर्थः ॥ **कर्मसंज्ञाप्रसङ्ग इति** । अपादानादिभिरसंकीर्तितत्वं च तत्प्राप्तिपूर्वकाविवक्षायामिव सर्वथा तदप्राप्तावपीति तात्पर्यम् । कर्मयुक्तत्वांशोपि तत्र परिगणनलभ्य एवेति बोध्यम् ॥

(अकारकत्वाभ्युपगमभाष्यम्)

अस्तु तर्ह्यकारकम् ॥

(१०९४ अकारकत्वदूषणवार्तिकम् ॥ २ ॥)

॥ * ॥ अकारकमिति चेदुपयोगवचनानर्थक्यम् ॥ * ॥

(भाष्यम्) **यद्यकारकमुपयोगवचनमनर्थकम् ॥**

(कारकत्वाभ्युपगमभाष्यम्)

अस्तु तर्हि कारकम् ॥

(उद्द्योतः) **अस्तु तर्हि कारकमिति** । गीतद्वारा तस्य तज्जनकत्वाद्द्वारिणो नान्यथासिद्धिरिति तद्विवक्षैवेति भावः ॥

(आक्षेपकारणभाष्यम्)

ननु चोक्तम्—*आख्यातानुपयोगे कारकमिति चेदकथितत्वात्कर्मसंज्ञाप्रसङ्गः* इति ॥

(समाधानभाष्यम्)

नैष दोषः। परिगणनं तत्र क्रियते—"दुहियाचिरुधिप्रच्छिभिक्षिचिञाम्" इति॥

(सूत्रप्रत्याख्यानाधिकरणम्)

(प्रत्याख्यानभाष्यम्)

अयमपि योगः शक्योऽवक्तुम्॥

(आक्षेपभाष्यम्)

कथमुपाध्यायादधीत इति?॥

(समाधानभाष्यम्)

अपक्रामति तस्मात्तदध्ययनम्॥

(उद्द्योतः) **अपक्रामति, तस्मात्तदध्ययनमिति।** अधीयमानवाक्यजातमध्ययनमित्युच्यते। एवं चापक्रमजनितविश्लेषाश्रयत्वादुपाध्यायस्यापादानत्वं सिद्धम्। उपाध्यायादपक्रान्तं शब्दजातमुपादत्ते इत्यर्थादिति भावः॥

(आक्षेपभाष्यम्)

यद्यपक्रामति किं नात्यन्तायापक्रामति?॥

(प्रदीपः) **यद्यपक्रामतीति।** यथा फलं वृक्षादपक्रान्तं न पुनर्वृक्षे तद्भवति एवं शब्देपि प्रसङ्ग इत्यर्थः॥

(उद्द्योतः) शब्दानामपक्रमणं न युक्तमिति शङ्कते—**यद्यपेति॥**

(समाधानभाष्यम्)

सन्ततत्वात्। अथ वा ज्योतिर्वज्ज्ञानानि भवन्ति॥ आख्यातोपयोगे॥ २९॥

(प्रदीपः) **संततत्वादिति।** शब्दस्य व्यञ्जका ध्वनय उपाध्यायेनोत्पाद्यमाना भिन्ना अपि सादृश्यात्तत्त्वेनाध्यवसीयमानाः श्रोतुः पुनः पुनः श्रोत्रप्रदेशं गच्छन्तो व्यक्तिस्फोटरूपं जातिस्फोटरूपं वा शब्दमभिव्यञ्जयन्तीत्यर्थः॥ **अथ वेति।** यथा ज्वालारूपं ज्योतिरविच्छेदेनोत्पद्यमानं सादृश्यात्तत्त्वेनाध्यवसीयमानं संततं तथैवोपाध्यायज्ञानानि भिन्नानि भिन्नशब्दरूपतामापद्यमानानि संततान्युच्यन्ते। ज्ञानस्य शब्दरूपापत्तिरिति दर्शनमत्र भाष्यकारस्य। तथा चोक्तम्—

'वायोरणूनां ज्ञानस्य शब्दत्वापत्तिरिष्यते।
कैश्चिद्दर्शनभेदो हि प्रवादेष्वनवस्थितः॥'

इति॥ २९॥

(उद्द्योतः) **शब्दस्य व्यञ्जका ध्वनय इति।** पुनःपुनरुत्पाद्यमानत्वेन सन्ततत्वमिति भावः॥ ननु तेषां भिन्नत्वात्कथं तद्रूपानुषक्तस्य स्फोटस्य स एवायमित्येकताप्रत्ययोऽत आह—**सादृश्यादिति॥ यथा ज्वालारूपमिति।** प्रतिक्षणं विनश्यदपीत्यर्थः॥ सन्ततमिति। तथा व्यवहारविषय इति भावः॥ **वायोः** कैश्चित्परमाणूनां शब्दतन्मात्रादिरूपाणां कैश्चित्कैश्चिद् **ज्ञानस्य** शब्दत्वमिष्यते। तदुक्तं हरिणा—

"लब्धक्रियः प्रयत्नेन वक्तुरिच्छानुवर्तिना।
स्थानेष्वभिहतो वायुः शब्दत्वं प्रतिपद्यते"॥

वक्तुरिच्छेत्यनेनैकस्यैव वायोरनेकशब्दत्वोपपत्तिरुक्ता॥ तथा—

"अणवः सर्वशक्तित्वाद्भेदसंसर्गवृत्तयः।
छायातपतमःशब्दभावेन परिणामिनः॥
स्वशक्तौ व्यज्यमानायां प्रयत्नेन समीरिताः।
अभ्राणीव प्रतीयन्ते शब्दाख्याः परमाणवः"॥

तथा—

"अथायमान्तरो ज्ञाता सूक्ष्मवागात्मना स्थितः।
व्यक्तये स्वस्वरूपस्य शब्दत्वेन विवर्तते"॥

ज्ञाता वृत्तिविशिष्टमन्तःकरणम्।

"स मनोभावमापद्य तेजसा पाकमागतः"।

तेजसा, जाठरेण। पाकं, दाहम्॥

"वायुमाविशति प्राणमथासौ समुदीर्यते"।

असौ सवृत्तिमनोयुतः प्राणः॥

तदाह—

"अन्तःकरणतत्त्वस्य वायुराश्रयतां गतः।
तद्धर्मेण समाविष्टस्तेजसा सोपि पच्यते"॥

तद्धर्मेण दाहेन।

दाहवशादेव

विभज्य स्वात्मनो ग्रन्थीन् श्रुतिरूपैः पृथग्विधैः॥

श्रुतिरूपैः, ध्वनिरूपैः सहेति शेषः।

"प्राणो वर्णानभिव्यज्य वर्णेष्वेवोपलीयते"॥

इति। **प्राणः** सवृत्तिकमनोरूपान्तःकरणयुतः। एतावतैव ज्ञानस्य शब्दत्वमिति द्रष्टव्यम्॥ **दर्शनं** सिद्धान्तः। **प्रवादः**, शास्त्राणि। नटस्य शृणोतीत्यादावीदृशबुद्धिकृतापायविवक्षानभिधानान्नेति नातिप्रसङ्गः॥ २९॥

(१८३ अपादानसंज्ञासूत्रम्॥ १।४।३ आ. ८ सू.)

२७० जनिकर्तुः प्रकृतिः॥ १।४।३०॥

(प्रत्याख्यानाधिकरणम्)

(प्रत्याख्यानभाष्यम्)

अयमपि योगः शक्योऽवक्तुम्॥

---

* अत्र प्रकृतिः समवाय्यसमवायिनिमित्तरूपत्रिविधकारणमध्येऽप्युपादानकारणम्। तेन मृदो घटो जायते तन्तुभ्यो वस्त्रं जायते 'ब्रह्मणः प्रजाः प्रजायन्ते' इत्यादिषु पञ्चमी उपादानकारणे जायते। 'वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्' इति श्रुतौ दार्ष्टान्तिकेन मृद उपादानकारणभूताया दृष्टान्तत्वेन ब्रह्मणोपि उपादानकारणत्वमेव वेदस्य भगवतोऽभिमेतम्। अत एव 'यत्प्रयन्त्यभिसंविशन्ति च' इत्यत्र दार्ष्टान्तिकोभिसंवेशो घटस्य मृदीव पटस्य तन्तुष्विव प्रपञ्चस्य ब्रह्मणि संगच्छते।

'आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः'।

इत्यत्रापि प्रजाया अन्नमिव अन्नस्य वृष्टिरिव वृष्टेरादित्योपि पञ्चमीविधोपक्रमानुरोधादुपादानकारणमेव। तथाहि किं वृष्टिर्न जायते स्वरूपवत

(आक्षेपभाष्यम्)

कथं गोमयाद् वृश्चिको जायते । गोलोमाविलोमभ्यो दूर्वा जायन्त इति ? ॥

(समाधानभाष्यम्)

अपक्रामन्ति तास्तेभ्यः ॥

(प्रदीपः) **जनिकर्तुः ॥ ३० ॥ अपक्रामन्ति ता** इति । लोकप्रसिद्ध्याश्रयेणैतदुच्यते । लोके हि यद्यस्माज्जायते तत्तस्मान्निर्गच्छतीत्युच्यते । तर्काश्रयास्तु प्रक्रिया भिद्यन्ते । वैशेषिकदर्शने परमाण्वादिसमवेतं कारणेभ्योऽपृथग्देशं कार्यमुत्पद्यत इति नास्ति कार्यस्यापक्रमः । सांख्यदर्शनेप्याविर्भावतिरोभावलक्षणजन्मनाशरूपपरिणामाभ्युपगमान्नास्त्यपक्रमः ॥

(उद्द्योतः) जनिकर्तुः ॥ ३० ॥ ननूपादानकारणे समवेततयोत्पद्यमानस्य कथं ततोपक्रम इत्यत आह—**लोकेति** । यथा वृक्षजन्यफले वृक्षादपक्रान्तत्वव्यवहारः ॥ **तर्काश्रयाः**, शास्त्राश्रयाः । **तर्काश्रया** इति पाठेपि स एवार्थः ॥

(आक्षेपभाष्यम्)

यद्यपक्रामन्ति किं नात्यन्तायापक्रामन्ति ? ॥

(प्रदीपः) **यदीति** । यद्यतोपक्रामति तत्पुनस्तत्र न दृश्यते इति प्रसिद्धम् । इह तु तत्रास्ति दर्शनमिति प्रश्नः ॥

(उद्द्योतः) **तत्रास्तीति** । जन्मोत्तरमिति भावः ॥

(समाधानभाष्यम्)

सन्ततत्वात् । अथ वान्याश्चान्याश्च प्रादुर्भवन्ति ॥ जनिकर्तुः ॥ ३० ॥

(प्रदीपः) **संततत्वादिति** । अविच्छेदादित्यर्थः । यथा बिलाद्दीर्घभोगो भोगी निष्क्रामन्नप्यविच्छेदात्तत्रोपलभ्यते तथा दूर्वा अपीत्यर्थः । **अथ वेति** । क्षणिकपक्षं द्रव्यान्तरारम्भपक्षं वा परिणामपक्षं वाश्रित्यैतदुक्तमित्याहुः ॥ ननु सतो जन्मायोगादसतश्च कर्तृत्वासंभवात्पक्षान्तराभावाच्च कथमङ्कुरो जायत इति प्रयोगः । नैष दोषः । बुद्धिव्यवस्थापितस्यार्थस्य क्रियायां कारकरूपोपगमात् ॥ ३० ॥

(उद्द्योतः) **द्रव्यान्तरारम्भेति** । खण्डपटादिरीत्येत्यर्थः । **परिणामेति** । सांख्यमते प्रतिक्षणपरिणामित्वात्पदार्थानां गोरोमादेस्तत्तदवस्थदूर्वारूपेण परिणाम इति भावः । **जन्मायोगादिति** । वैफल्यादिति भावः ॥ **कर्तृत्वासम्भवादिति** । किं चैवं शशविषाणादेरप्युत्पत्तिप्रसङ्गः । किं चैतन्मते कलिकावस्थायामसत एव गन्धस्य विकासावस्थायामुत्पत्तिर्वाच्या । एवं च सर्वपुष्पेषु विकासमात्रेण गन्धोत्पत्त्यापत्तिः । एवं बाल्येऽविद्यमानस्य शुक्रशोणितादेर्यौवने उत्पत्तौ तृतीयप्रकृतावपि तदुत्पत्तिप्रसङ्ग इति बोध्यम् ॥ उत्तरम्—**बुद्धीति** । **कारकरूपं**, कारकत्वम् ॥ ३० ॥

(१८४ अपादानसंज्ञासूत्रम् ॥ १ । ४ । ३ आ. ९ सू.)

२७१ भुवः प्रभवः ॥ १ । ४ । ३१ ॥

(प्रत्याख्यानाधिकरणम्)

(प्रत्याख्यानभाष्यम्)

अयमपि योगः शक्योऽवक्तुम् ॥

(आक्षेपभाष्यम्)

कथं हिमवतो गङ्गा प्रभवतीति ? ॥

(समाधानभाष्यम्)

अपक्रामन्ति तास्तस्मादापः ॥

(आक्षेपभाष्यम्)

यद्यपक्रामन्ति किं नात्यन्तायापक्रामन्ति ॥

(समाधानभाष्यम्)

सन्ततत्वात् ॥ अथ वान्याश्चान्याश्च प्रादुर्भवन्ति ॥ भुवः प्रभवः ॥ ३१ ॥

(प्रदीपः) **भुवः प्र ॥ ३१ ॥ सन्ततत्वादिति** । सादृश्यनिबन्धनतत्त्वाध्यवसायादविच्छेदेन तासामुपलम्भादित्यर्थः ॥ **अथ वेति** । वस्तुतोत्र भेद एवापामिति भावः ॥ ३१ ॥

(उद्द्योतः) भुवः प्र—॥ ३१ ॥ **भेद एवापामिति** । सादृश्यमूलकोपि नाभेदाध्यवसाय इति भावः ॥ ३१ ॥

(इति कारकप्रकरणेऽपादानसंज्ञाप्रकरणम्)

(अथ कारकप्रकरणे संप्रदानसंज्ञाप्रकरणम्)

(१८५ संप्रदानसंज्ञासूत्रम् ॥ १ । ४ । ३ आ. १० सू.)

२७२ कर्मणा यमभिप्रैति स सम्प्रदानम् ॥ १ । ४ । ३२ ॥

(पदकृत्याधिकरणम्)

(अनुयोगभाष्यम्)

कर्मग्रहणं किमर्थम् ? ॥

(प्रदीपः) **कर्मणायम् ॥ ३२ ॥ कर्मग्रहणमिति** । उपाध्यायाय गां ददातीत्यत्र गोरुपाध्यायस्याप्यभिप्रेयमाण-

---

आविर्भावस्य सर्वदा विद्यमानत्वात् । तस्मादादित्यपदं तत्र विलक्षणधर्मपर्यायज्योतिःपरमेव । एवं च तादृग्ज्योतिरेव वृष्टिरूपेण परिणमते, वृष्टिरेवान्नरूपेण, अन्नमेव प्रजारूपेण परिणमते इत्येव पञ्चाग्निविद्याप्रक्रमतो निश्चीयते ॥ एवं पुष्पस्यापि न स्वरूपतः गन्धोत्पत्तौ हेतुत्वम् । किंतु तदीयगन्धगुणापगुणस्थानमेव गन्धोत्कर्षरूपेण परिणमते इति बोध्यम् ॥ अतएव गोलोमादीनामपि दूर्वारूपेण परिणाम एवेति भाष्यसंमतम् ॥ अत एव भाष्ये संततत्वादित्युक्तम् । तस्य च तूलराशेरिव गोलोमादीनामपि परिणामित्वाङ्गीकारसूचनपूर्वकोपादानकारणत्वसूचन एव तात्पर्यम् ॥ अस्तु वा पुष्पाद्गन्धो जायत इत्यत्र धूमादग्निमनुमिमीते इतिवत् इत्यत्रैव "विभाषा गुणे" इत्यत्र विभाषेति योगविभागेन पञ्चमी । तथा च न तद्दृष्टान्तेन ब्रह्मणो निमित्तकारणत्वं पञ्चम्या सिध्यति किंच 'तदैक्षत बहु स्यां प्रजायेय' इति श्रुतौ 'कुर्याम्' इत्यनुक्त्वा 'स्याम्' 'प्रजायेय' इत्युक्त्यापि ब्रह्मण उपादानकारणत्वमेव सिध्यतीत्यलं वेदविरुद्धहठिखण्डनेनेति शम् ॥ १—परिणामपक्षमिति । परिणामविवर्तयोरवान्तरभेदस्त्वकिंचित्कर इति भावः ॥

त्तम् । यतो गौर्दानक्रियया करणभूतयाऽभिप्रेयते गवा तूपाध्यायः । तत्र परत्वाद्गोः कर्मसंज्ञेति पारिशेष्यादुपाध्यायस्यैव संप्रदानसंज्ञा भविष्यतीति प्रश्नः ॥

(उद्द्योतः) कर्मणायम् ॥ ३२ ॥ नन्वसत्यस्मिन् कर्मण्यपि स्यादित्यत आह—उपाध्यायायेति ॥ करणभूतयेति । स्वरूपकथनम् ॥

(समाधानभाष्यम्)

"यमभिप्रैति स सम्प्रदानम्" इतीयत्युच्यमाने कर्मण एव सम्प्रदानसंज्ञा प्रसज्येत । कर्मग्रहणे पुनः क्रियमाणे न दोषो भवति । कर्म निमित्तत्वेनाश्रीयते ॥

(प्रदीपः) कर्मण एवेति । सत्यप्युभयसंभवेन्तरङ्गत्वात्कर्मण एव गवादेः स्यादित्यर्थः । नन्वेवं कर्मसंज्ञानवकाशा स्यात् । वचनसामर्थ्यात्तर्हि पर्यायः स्यात् । कारकप्रकरणे च प्रकर्षयोगो नाश्रीयते न त्वन्तरङ्गबहिरङ्गव्यवहारः । ननु पर्याये सति गत्यर्थकर्मणीत्यारम्भोऽनर्थकः स्यात् । तस्य प्रत्याख्यातत्वादित्यदोषः ॥

(उद्द्योतः) अन्तरङ्गत्वादिति । दानक्रियाभिप्रेतगव्योपाध्यायोऽभिप्रेत इति तस्य क्रियासंबन्धो बहिरङ्ग इति भावः ॥ नन्वेवमिति । दायोग एव संप्रदानत्वमित्यस्यानाश्रयणादिति भावः ॥ प्रकर्षयोगः, सामर्थ्यगम्यप्रकर्षयोगः ॥ प्रत्याख्यातत्वादिति । सिद्धान्तेप्यनुवादत्वेनेदानीमपि तत्त्वमेवेति भावः ॥ अत्र कर्मणेति निर्दिष्टस्य शेषत्वं यमिति निर्दिष्टस्योद्देश्यत्वलक्षणं शेषित्वं प्रतीयते इत्यजां ग्रामं नयतीत्यादौ ग्रामस्य न संप्रदानत्वमिति बोध्यम् । यदा तु ग्रामोऽजासंयुक्तो भवत्वित्युद्देशेनाजानयनं तदा भवत्येवाजां ग्रामाय नयतीति ॥

(अनुयोगभाष्यम्)

अथ यंसग्रहणं किमर्थम् ? ॥

(प्रदीपः) अथेति । अध्याहारेणापि सर्वनामद्वयार्थो लभ्यत इति प्रश्नः ॥

(उद्द्योतः) ननु संज्ञिनिर्देशार्थं तदावश्यकमत आह—अध्याहारेणापीति ।

(समाधानभाष्यम्)

"कर्मणाभिप्रैति सम्प्रदानम्" इतीयत्युच्यमाने अभिप्रयत एव सम्प्रदानसंज्ञा प्रसज्येत । यंसग्रहणे पुनः क्रियमाणे न दोषो भवति । यंसग्रहणादभिप्रयतः सम्प्रदानसंज्ञा निर्भज्यते ॥

(प्रदीपः) अभिप्रयत एवेति । श्रुतपदार्थसंबन्धेनैव निराकाङ्क्षत्वेऽध्याहारानुपपत्तिरिति भावः । कर्तृसंज्ञायास्त्वकर्मको धातुरवकाशः स्यात् । ततश्चोपाध्यायाय शिष्येण गौर्दीयते इत्यत्रार्थे शिष्यायोपाध्यायस्य गौर्दीयत इति स्यात् ॥ ननु शिष्यस्य कर्तृत्वाभावे कथं गोः कर्मसंज्ञा । नैष दोषः । कर्मसंज्ञायां स्वातन्त्र्यस्य कर्तृग्रहणेनोपलक्षणात् । तथा च सार्थाद्धीयत इत्यत्र कर्मणि लकारोत्पत्तिः ॥ निर्भज्यत इति । आकृष्यत इत्यर्थः ॥

(उद्द्योतः) श्रुतेति । तिङ्गुल्योपस्थापितेत्यर्थः । एवं च यः स इत्येव लभ्येतेति भावः ॥ सार्थादिति । प्रधानधात्वर्थव्यापाराश्रयत्वेऽपि अपादाने चाहीयरुहोरितिसूत्रेण कर्मप्रत्ययान्तहीधातुयोगेऽपादानत्वज्ञापनात्पञ्चमी सार्थेन त्यज्यते इत्यर्थकोयं प्रयोगः ॥ आकृष्यत इति । निराक्रियत इत्यर्थः ॥

(अनुयोगभाष्यम्)

अथाभिप्रग्रहणं किमर्थम् ?॥

(प्रदीपः) अथेति । कर्मणा यमेति गच्छति प्राप्नोति संबध्नातीत्यर्थः । अभिप्रैतीत्युक्ते स एवार्थ इति प्रश्नः ॥

(समाधानभाष्यम्)

"कर्मणा यमेति स सम्प्रदानम्" इतीयत्युच्यमाने यमेव सम्प्रत्येति तत्रैव स्यात्—उपाध्यायाय गां ददातीति । इह न स्याद्—उपाध्यायाय गामदादुपाध्यायाय गां दास्यतीति । अभिप्रग्रहणे पुनः क्रियमाणे न दोषो भवति । अभिराभिमुख्ये वर्तते, प्रशब्द आदिकर्मणि । तेन यं चाभिप्रैति यं चाभिप्रैष्यति यं चाभिप्रागादाभिमुख्यमात्रे सर्वत्र सिद्धं भवति ॥

(प्रदीपः) आभिमुख्य इति । उपसर्गद्वयोपादानसामर्थ्यात्कालानवच्छिन्ना क्रियाश्रीयत इत्यर्थः । ननु यथा तेन दीव्यतीत्यादौ संख्याकालयोर्न विवक्षा तथेहापि संख्यावत्कालस्याविवक्षा भविष्यतीति किमुपसर्गद्वयोपादानेन । एवं तर्हि न्यायसिद्ध एवार्थ उपसर्गद्वयोपादानेन प्रदर्श्यत इति भाष्यकारस्याभिप्रायः ॥

(उद्द्योतः) भाष्ये—यं संप्रत्येतीति । संनिहितसंप्रदानस्थले दानस्य तत्काले विप्रसन्तोषरूपदृष्टफलेनापि फलवत्त्वात्तत्रैव स्याद्, असंनिहितसंप्रदानस्थले विप्राय ददातीति न स्या.दिति भावः ॥ उपाध्यायायेत्यत्र संनिहितायेति शेषः । अग्रे विप्रकृष्टायेति शेषः ॥ आभिमुख्यमात्रे इति । कर्मणा करणभूतेन क्रियारम्भे यमुद्दिशतीत्यर्थः ॥ स चोद्देशः सर्वत्रास्तीति भावः ॥ संख्यावदिति । अन्यथा विप्रेभ्यो गां ददातीति न स्यादिति भावः ॥ न्यायसिद्ध एवेति । अयमभ्युपगमवादः ॥

(न्यूनतापूर्त्यधिकरणम्)

(१०९५ आक्षेपवार्तिकम् ॥ १ ॥)

[॥ * ॥ क्रियाग्रहणम् ॥ * ॥]

(भाष्यम्) **क्रियाग्रहणमपि कर्तव्यम् । इहापि यथा स्यात्—श्राद्धाय निगर्हते युद्धाय संनह्यते पत्ये शेते इति ॥**

(प्रदीपः) श्राद्धायेति । श्राद्धं निन्दति नास्तिकत्वा-

दित्यर्थः ॥ युद्धायेति । युद्धविषयं संनहनपूर्वकं निश्चयं करोतीत्यर्थः ॥ पत्ये शेत इति । पतिमुपसृत्य शेते इत्यर्थः॥

(उद्द्योतः) निन्दतीति । गर्ह कुत्सायामिति स्मृतेः । निश्चयं करोतीति । उद्देश्यत्वप्रदर्शनायेदम् । एवमुत्तरत्रोपसत्स्वेत्यपि । उपाश्रित्येति पाठान्तरम् ॥

(आक्षेपभाष्यम्)

तत्तर्हि वक्तव्यम् ?॥

(समाधानभाष्यम्)

न वक्तव्यम् ॥ कथम् ? । क्रियां हि नाम लोके कर्मेत्युपचरन्ति—कां क्रियां करिष्यसि—किं कर्म करिष्यसीति ॥

(उद्द्योतः) भाष्ये क्रियां हीति । एवं च बहुलक्ष्यसंस्कारानुरोधेन कर्मशब्देनोभयं गृह्यते ॥

(समाधानबाधकभाष्यम्)

एवमपि कर्तव्यम् । कृत्रिमाकृत्रिमयोः कृत्रिमे सम्प्रत्ययो भवति ॥

(समाधानसाधकभाष्यम्)

क्रियापि कृत्रिमं कर्म ॥

(समाधानबाधकभाष्यम्)

न सिद्ध्यति । "कर्तुरीप्सिततमं कर्म" इत्युच्यते । कथं च नाम क्रियया क्रियेप्सिततमा स्यात् ? ॥

(प्रदीपः) न सिध्यतीति । क्रियान्तरानुपादानादिति भावः ॥ कथं च नामेति । क्रियान्तरानुपादाने एकस्या एव क्रियायाः कर्मकरणभाव एकदा एकात्मन्येव नोपपद्यत इति भावः ॥

(उद्द्योतः) भाष्ये—न सिध्यतीति । कृत्रिमकर्मत्वं क्रियाया न सिध्यतीत्यर्थः ॥ ननु पश्य धावतीत्यादौ क्रियाया अपि तत्त्वदर्शनादाह—क्रियान्तरेति ॥ भिन्नकाले भिन्नरूपेण च कर्तृकर्मताया एकस्मिन्नपि दर्शनादाह—एकदा एकात्मन्येवेति । अत्रत्यं भाष्यं कर्तरि कर्मेत्यत्र व्याख्यातम् ॥

(समाधानसाधकभाष्यम्)

क्रियापि क्रिययेप्सिततमा भवति । कया क्रियया ? । सन्दर्शनक्रियया प्रार्थयतिक्रिययाऽध्यवस्यतिक्रियया च । इह य एष मनुष्यः प्रेक्षापूर्वकारी भवति । स बुद्ध्या तावत्कंचिदर्थं पश्यति, संदृष्टे प्रार्थना, प्रार्थनायामध्यवसायः, अध्यवसाय आरम्भः, आरम्भे निर्वृत्तिः, निर्वृत्तौ फलावाप्तिः । एवं क्रियापि कृत्रिमं कर्म ॥

(प्रदीपः) क्रियापीति । प्रतीयमानक्रियापेक्षः कारकभावः प्रविश पिण्डीमित्यादावविवक्षित इत्यर्थः । यदा तु संदर्शनादयो धात्वर्थाभेदेन विवक्ष्यन्ते तदा संप्रदानसंज्ञा अन्यदा तु कर्मसंज्ञैव यथा कटं करोतीति । सा च भेदाभेदविवक्षा प्रयोगदर्शनवशेन नियतविषयैवाश्रीयत इति प्रयोगस्यासंकरः ॥

(उद्द्योतः) ननु संदर्शनादीनां सर्वत्र भावात्सर्वत्र संप्रदानत्वं स्यादत आह—यदा त्विति । एवं च पत्ये शेते इत्यादेर्दर्शनादिपूर्वकारम्भकर्मपत्युद्देश्यकं शयनं करोतीत्यर्थः ॥ भेदेनेति । तत्तद्रूपेण बोधविषयतया विवक्ष्यत इत्यर्थः ॥ यथा कटं करोतीति । तत्र हि कटकर्मकक्रियेत्येव बोधो न तु तस्याः क्रियाया विद्यमानमपि संदर्शनादिपूर्वकारम्भकर्मत्वं तत्तद्रूपेण बोधविषय इति भावः ॥

(भाष्यम्)

एवमपि—

(१०९६ आक्षेपवार्तिकम् ॥ २ ॥)

[॥ * ॥ कर्मणः करणसंज्ञा संप्रदानस्य च कर्मसंज्ञा ॥ * ॥]

(भाष्यम्) **कर्मणः करणसंज्ञा वक्तव्या सम्प्रदानस्य च कर्मसंज्ञा । पशुना रुद्रं यजते । पशुं रुद्राय ददातीत्यर्थः । अग्नौ किल पशुः प्रक्षिप्यते तद्रुद्रायोपह्रियत इति ॥ कर्मणा यमभिप्रैति ॥ ३२ ॥**

(प्रदीपः) कर्मणः करणसंज्ञेति । एतच्छन्दोविषयम् । सर्वे विधयश्छन्दसि विकल्प्यन्त इति यथाप्राप्तमपि प्रयोगो भवति ॥ पशुना रुद्रं यजत इति । रुद्रं देवतामुद्दिश्य पशुं त्यजतीत्यर्थः ॥ कैश्चिदन्वर्थसंज्ञाविज्ञानाद्ददातिविषय एव संप्रदानसंज्ञेत्यभ्युपगतम् । दानं च स्वत्वनिवृत्तिः परस्वत्वापत्तिपर्यन्तेति प्रत्यज्ञायि ॥ तदुभयमप्ययुक्तम् । अन्यत्रापि भाष्यकारेण संज्ञाया अभ्युपगमात् । तथा च क्रियाग्रहणस्य गत्यर्थकर्मणीति सूत्रस्य च प्रत्याख्यानं कृतम् । तथा स्वत्वनिवृत्त्यभावेपि ददातेः प्रयोगो दृश्यते न शूद्राय मतिं दद्यादिति । खण्डिकोपाध्यायस्तस्मै चपेटां ददातीति च ॥ ३२ ॥

(उद्द्योतः) पशुं रुद्राय ददातीति भाष्यप्रयोगानुपपत्तेराह— एतच्छन्द इति ॥ ननु पूजायां पशोः करणत्वाद्रुद्रस्य च कर्मत्वात्किमुपसंख्यानेनेत्यत आह—त्यजतीत्यर्थ इति । अत्रार्थे त्वदुक्तं न सम्भवतीत्यर्थः ॥ त्यजतीत्यस्याभाविति शेषः । तदुक्तं भाष्ये—अग्नौ किल पशुः प्रक्षिप्यते इति ॥ नन्वेवं रुद्राय ददातीत्युक्तमनुपपन्नमत आह—तद्रुद्रायोपह्रियते इति । तत्र तेन प्रक्षेपेण रुद्राय रुद्रमुद्दिश्य उपह्रियते ददातीति व्यवहार इत्यर्थः । अग्नौ दग्धे स्वत्वानुत्पत्त्या तदुद्देश्यकत्यागे ददातिर्भाक्त इति भावः ॥ अन्वर्थेति । सम्यक् प्रदीयतेऽस्मै इतीत्यर्थः ॥ नन्वेवमपि रजकस्य वस्त्रं ददातीत्यत्रापि स्यादत आह—दानं चेति । तत्र ददातिप्रयोगस्तूपमानात्, कारकशेषत्वात् षष्ठीति भावः ॥ अन्यत्रापीति । पत्ये शेते इत्यादावपीत्यर्थः ॥ पूर्वोक्तप्रयोगे तु शेषत्वविवक्षायां

षष्ठी ॥ न शूद्रायेत्यस्य मतिं तज्जनकशास्त्रं नोपदिशेदित्यर्थः । द्वितीये ददातिः संयोगे लाक्षणिक इति बोध्यम् ॥ ३२ ॥

(१८६ संप्रदानसंज्ञासूत्रम् १ । ४ । ३ आ. ११ सू.)

२७७ क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रति कोपः ॥ १ । ४ । ३७ ॥

(क्रोधादीनां कोपजन्यत्वसाधनाधिकरणम्)

(आक्षेपभाष्यम्)

किमेत एकार्थाः, आहोस्विन्नानार्थाः? ॥

(प्रदीपः) क्रुधद्रुह ॥ ३७ ॥ **किमेत इति** । ननु लोकव्यवहारादेवार्थावगमात्संदेहानुपपत्तिः । एवं तर्हि चित्तदोषरूपता सर्वेषामस्तीति सामान्यापेक्षायामेकार्थत्वम्, अवान्तरभेदविवक्षायां तु भिन्नार्थत्वमित्यदोषः ॥

(प्रत्याक्षेपभाष्यम्)

किं चातः? ।

(प्रत्याक्षेपसमाधानभाष्यम्)

यद्येकार्थाः किमर्थं पृथङ्निर्दिश्यन्ते? ॥ अथ नानार्थाः, कथं कुपिना शक्यन्ते विशेषयितुम्? ॥

(प्रदीपः) **किमर्थमिति** । एकेनैव धातुनार्थस्योपलक्षितत्वादन्येषां वैयर्थ्यप्रसङ्गः ॥ **नानार्था इति** । **क्रोधो** रोषः । **द्रोहो**ऽभिचारः । **ईर्ष्या** परगुणासहनम् । **असूया** परगुणविध्वंसनम् ॥

(उद्द्योतः) **क्रुधद्रुहेर्ष्या** ॥ ३७ ॥ ननु तेषां सर्वेषां योगे यथा स्यादित्येतदर्थं तदत आह—**एकेनैवेति** । सूत्रेऽर्थग्रहणसत्त्वादिति भावः ॥ **अभिचार इति** । दुःखजनको व्यापार इत्यर्थः ॥ परगुणासहनं एतत्स्वस्य तदधिकगुणसंपादनफलकम् ॥ **गुणविध्वंसनं** गुणेषु दोषत्वाविष्करणम् ॥

(समाधानभाष्यम्)

एवं तर्हि नानार्थाः । कुपी त्वेषां सामान्यमस्ति नह्यकुपितः क्रुध्यति । न वाऽकुपितो द्रुह्यति । न वाऽकुपित ईर्ष्यति । न वाऽकुपितोऽसूयति ॥ क्रुधद्रुहेर्ष्या ॥ ३८ ॥

(प्रदीपः) **कुपाविति** । कुपौ धातौ वाच्यत्वेन यदवस्थितं तदेषां साधारणमित्यर्थः । कोपपूर्वाणां सर्वेषां ग्रहणार्थं **यं प्रति कोप** इति विशेषणमित्यर्थः । तेनेह न भवति—भार्यामीर्ष्यतीति । परैर्दृश्यमानां न सहत इत्ययमत्रार्थ इति नास्ति कोपप्रभवत्वमत्रेर्ष्यायाः ॥ **नह्यकुपितः क्रुध्यतीति** ॥ ननु कोपः क्रोध एवेति भेदाभावात्कथं पौर्वापर्यम् । एवं तर्हि प्रथमामनुद्भूतां कोपावस्थां द्वितीयां चोद्भूतां विकृतवाक्कायव्यापारानुमीयमानामाश्रित्यैतदुक्तमित्यदोषः ॥ **न वाऽकुपितो द्रुह्यतीति** । यत्र विषये संप्रदानसंज्ञेष्यते तदुद्देशेनैतदुच्यते, न तु सर्वविषयापेक्षया । अन्यथा व्यभिचाराभावाद्यं **प्रति कोप** इति विशेषणमनुपादेयं स्यात् । भार्यामीर्ष्यतीति विनापि कोपात्प्रयोगदर्शनाच्च । **अस्मान्द्वेष्टी**त्यत्र संप्रदानसंज्ञा न भवति द्विषेरक्रोधार्थत्वात् । अनभिनन्दने द्विषिर्वर्तते यथौषधं द्वेष्टीति ॥ ३७ ॥

(उद्द्योतः) नन्विदमयुक्तं नहि क्रुधादीनां सामान्यं कुपिधातावस्तीत्यत आह—**कुपौ धाताविति** । **अनभिनन्दनं** प्रीत्यभावः ॥ ३७ ॥

(इति कारकप्रकरणे संप्रदानप्रकरणम्)

(अथ कारकप्रकरणे करणसंज्ञाप्रकरणम्)

(१८७ करणसंज्ञासूत्रम् ॥ १ । ४ । ३ आ. १२ सू.)

२८२ साधकतमं करणम् । १ । ४ । ४२ ॥

(तमग्रहणप्रयोजनाधिकरणम्)

(आक्षेपभाष्यम्)

तमग्रहणं किमर्थम् ; न "साधकं करणम्" इत्येवोच्येत ॥

(प्रदीपः) **साधक ॥ ४२ ॥ तमग्रहणमिति** । कारकाधिकारात्साधकत्वे लब्धे पुनः साधकश्रुतिः प्रकर्षमवगमयतीति प्रश्नः ॥

(उद्द्योतः) **साधकतमं** ॥ ४२ ॥ अत्र कारकाधिकारात् क्रियानिरूपितातिशयितकारकत्ववत्करणमित्यर्थः । अतिशयश्च यद्व्यापारानन्तरमव्यवधानेन फलोत्पत्तिस्तत्त्वम् ॥ ननु पूर्वोक्तातिशयबोधकतया तत्सार्थकमत आह—**कारकाधिकारादिति** ।

(आक्षेपबाधकभाष्यम्)

"साधकं करणम्" इतीयत्युच्यमाने सर्वेषामेव कारकाणां करणसंज्ञा प्रसज्येत । सर्वाणि हि कारकाणि साधकानि । तमग्रहणे पुनः क्रियमाणे न दोषो भवति ॥

(प्रदीपः) **सर्वेषामेवेति** । प्रकर्षगतिरुत्तरत्र प्रतिपादयिष्यते । तत्र वचनसामर्थ्यादेकसंज्ञाधिकाराच्च करणसंज्ञायाः संज्ञान्तराणां च विकल्पः स्यात् ॥ नन्वसति विशेषाश्रयणे करणकारकसंज्ञाद्वयोपादानमनर्थकं स्यात् ॥ तर्हि संज्ञाद्वयविधानसामर्थ्यात्करणसंज्ञा कंचिदेव विषयं परिहरतीति लभ्यते । न त्वनिष्टविषयपरिहारेणेष्टविषये तस्याः प्रवृत्तिर्लभ्या ॥

(उद्द्योतः) ननु सर्वेषां करणत्वे संज्ञान्तराणां का गतिरत आह—**तत्रेति ॥ संज्ञाद्वयेति** । कारकसंज्ञैव कार्याऽन्वर्थसंज्ञया च स्वोनुरूपः संख्याक्षेप्यः 'कारके तृतीया'इत्येव कार्यमिति भावः ॥

(आक्षेपसाधकभाष्यम्)

नैतदस्ति प्रयोजनम्। पूर्वास्तावत्संज्ञा अपवादत्वाद्बाधिका भविष्यन्ति। पराः परत्वादनवकाशत्वाच्च॥

(प्रदीपः) **परत्वादनवकाशत्वाच्चेति।** विषयभेदापेक्षो हेतुद्वयोपन्यासः। सावकाशत्वे सति परत्वं हेतुः, अन्यत्र निरवकाशत्वम्॥

(उद्द्योतः) ननु सावकाशत्वे एव परत्वस्य व्यवस्थापकत्वादेकविषये द्वयोः परत्वानवकाशत्वयोरसम्भवादाह—**विषयभेदेति। सावकाशत्वे** इत्युक्तिरभ्युपगम्यवादेन, नहि तमाभावे करणत्वविनिर्मुक्तः संज्ञान्तरविषयोस्ति। वस्तुतो भाष्ये **परत्वाच्चे**त्यस्योत्कृष्टत्वाच्चेत्यर्थकस्य व्याख्याऽनवकाशत्वाच्चेति॥

(आक्षेपबाधकभाष्यम्)

इह तर्हि 'धनुषा विध्यति' अपाययुक्तत्वाच्चापादानसंज्ञा साधकत्वाच्च करणसंज्ञा प्राप्नोति। तमग्रहणे पुनः क्रियमाणे न दोषो भवति॥

(प्रदीपः) **इह तर्हीति।** अत्र संज्ञाद्वयप्रसङ्गे निरवकाशत्वादपादानसंज्ञैव स्यात्। करणसंज्ञा ह्यपादानादन्यत्र सावकाशा। तमग्रहणे तु सति विविक्तविषयलाभादुभयोर्धनुषा विध्यतीत्यत्र परत्वात्करणसंज्ञा सिध्यतीति॥

(उद्द्योतः) ननु संज्ञाद्वयप्रसङ्गे परत्वात्करणत्वं सिध्यतीत्यत आह—**अत्रेति॥ अपादानादन्यत्रेति।** काष्ठैः पचतीत्यादौ॥

(आक्षेपसाधकभाष्यम्)

एवं तर्हि लोकत एतत्सिद्धम्। तद्यथा लोके 'अभिरूपायोदकमानेयमभिरूपाय कन्या देया' इति। न चानभिरूपे प्रवृत्तिरस्ति। तत्र 'अभिरूपतमाय' इति गम्यते। एवमिहापि साधकं करणमित्युच्यते। सर्वाणि च कारकाणि साधकानि, न चासाधके प्रवृत्तिरिति तत्र 'साधकतमम्' इति विज्ञास्यते॥

(प्रदीपः) **उदकमानेयमिति।** कन्यादानार्थम्। **न चानभिरूप इति।** दृष्टादृष्टप्रयोजनत्वात्कन्यादानस्येति भावः॥

(उद्द्योतः) उदकादाने आभिरूप्यस्यानियामकत्वादाह—**कन्यादानार्थमिति। दृष्टं** कन्यासुखसन्तानादि। **अदृष्टं** परलोकः॥ **न चासाधके इति।** संज्ञाया इति शेषः॥

(समाधानभाष्यम्)

एवं तर्हि सिद्धे सति यत्तमग्रहणं करोति तज्ज्ञापयत्याचार्यः—कारकसंज्ञायां तरतमयोगो न भवतीति॥

(प्रदीपः) **तरतमयोगो नास्तीति।** कथं पुनः केवलयोः प्रत्यययोः प्रयोगः। नैष दोषः। प्रत्ययानुकरणत्वात्। तत्रानुकरणाभ्यामनुकार्यौ प्रत्ययौ प्रतीयेते ताभ्यामपि साहचर्यात्तदर्थो लक्ष्यते॥ तत्र तमश्रुतिरेतज्ज्ञापयति प्रकर्षप्रत्ययग्रहणमन्तरेणेह प्रकरणे सामर्थ्यगम्यः प्रकर्षो नाश्रीयते॥

(उद्द्योतः) **लक्ष्यते इति।** अत एव ततः स्वार्थे ष्यञि तारतम्यमित्यतिशये सिध्यति॥ तरतमेत्यतिशयार्थमव्ययमित्यन्ये। एवमेवातिशयार्थकं तरामित्यप्यव्ययं बोध्यम्॥ उच्चारितस्यैव प्रत्ययत्वात्तत्प्रतीतानुकार्येणातिशयप्रतीतिरिति चिन्त्यम्॥ नन्वत्र प्रकरणे तरतमयोगाभावे ईप्सितमात्रस्य कर्मत्वं प्राप्नोतीत्यत आह—**तत्र तमेति॥**

(प्रयोजनप्रश्नभाष्यम्)

किमेतस्य ज्ञापने प्रयोजनम्?॥

(प्रयोजनभाष्यम्)

अपायमाचार्यः किं न्याय्यं मन्यते? यत्र संप्राप्य निवृत्तिः। तेनेहैव स्यात्—ग्रामादागच्छति। सांकाश्यकेभ्यः पाटलिपुत्रका अभिरूपतरा इत्यत्र न स्यात्। 'कारकसंज्ञायां तरतमयोगो न भवति' इत्यत्रापि सिद्धं भवति॥

(प्रदीपः) **सांकाश्यकेभ्य इति।** बुद्धिकल्पितोत्रापायो न तु मुख्यः॥

(उद्द्योतः) **बुद्धिकल्पित इति।** अपादानमिति महासंज्ञयैवापाये ध्रुवे लब्धे पुनस्तद्ग्रहणसामर्थ्यात्प्रकर्षविवक्षायामत्र न स्यादिति भावः॥

(प्रयोजनभाष्यम्)

तथाधारमाचार्यः किं न्याय्यं मन्यते? यत्र कृत्स्न आधारात्मा व्याप्तो भवति। तेनेहैव स्यात्—तिलेषु तैलं दध्नि सर्पिरिति। गङ्गायां गावः कूपे गर्गकुलमित्यत्र न स्यात्। कारकसंज्ञायां तरतमयोगो न भवतीत्यत्रापि सिद्धं भवति॥ साधकतमं करणम्॥ ४२॥

(प्रदीपः) **यत्र कृत्स्न इति।** सर्वैरवयवैः सह यत्रावयवी व्याप्त इत्यर्थः॥ **गङ्गायामिति।** गोभिर्गङ्गाया व्याप्त्यभावान्न स्यादधिकरणसंज्ञा। अस्माज्ज्ञापकात्सामीप्यमात्राश्रयेण प्रकल्पिताधारनिबन्धना सा भवति॥ अथ सामग्रीसाध्यायां क्रियायां कोतिशयः करणस्येति चेत्। यद्व्यापारानन्तरं क्रियाप्रसिद्धिः। यस्य च यदातिशयविवक्षा तदा तस्य करणत्वं यथा स्थाल्या पच्यत इति। कारकान्तरापेक्षश्च करणस्यातिशयो न तु स्वकक्षायामित्यश्वेन दीपिकया पथा व्रजतीति सर्वेषां क्रियानिष्पत्तौ संनिपत्योपकारकत्वात्करणत्वं सिद्धम्॥ ४२॥

(उद्द्योतः) **सामीप्यमात्राश्रयेणेति।** तेनापीत्यर्थः। अपि नैकदेशवृत्तिताश्रयेणेत्यस्य संग्रहः॥ **प्रकल्पितेति।** संपूर्णप्रवाहे एकदेशधर्मस्य तीरधर्मस्य वाऽऽधारत्वस्योपचार इति भावः। तादृशमाधा-

रत्वमपि सप्तम्याः शक्यमेवेति बोध्यम् ॥ स्थाल्या पच्यते इति । प्रतनुतरकपालतयात्रातिशयविवक्षा बोध्या । अश्वेन यथेत्यादिष्वपि प्रत्यासन्नस्य कस्यचिदेव करणत्वं स्यादिति भावः ॥ संनिपत्येति । खलेकपोतन्यायेन सर्वेषां साक्षादुपकारकत्वविवक्षणादित्यर्थः ॥४२॥

(इति कारकप्रकरणे करणसंज्ञाप्रकरणम्)

(अथ कारकप्रकरणे कर्मसंज्ञाप्रकरणम्)

(१८८ कर्मसंज्ञासूत्रम् ॥ १ । ४ । ३ आ. १३ सू.)

२८८ उपान्वध्याङ्वसः ॥ १ । ४ । ४८ ॥

(अनिष्टवारणाधिकरणम्)

(१०९७ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ वसेरश्यर्थस्य प्रतिषेधः ॥ * ॥

(भाष्यम्) **वसेरश्यर्थस्य प्रतिषेधो वक्तव्यः । ग्रामे उपवसतीति ॥**

(प्रदीपः) उपान्व ॥ ४८ ॥ वसेरश्यर्थस्येति । अर्थशब्दो निवृत्तिवाची । व्यधिकरणे षष्ठ्यौ । अश्यर्थस्य वाचको यो वसिस्तस्येत्यर्थः । अथवा शीडोर्थः श्यर्थः न श्यर्थोऽश्यर्थः । तस्य अस्थानार्थस्येत्यर्थः । स्थाने हि शीङ् वर्तते यथा जलाशय इति । तेन ग्रामे तिष्ठतीत्यत्रार्थे ग्राममुपवसतीति प्रयोगः । अस्थानार्थत्वे तु ग्राम उपवसतीति ॥

(उद्द्योतः) उपान्वध्या ॥ ४८ ॥ ननूपपूर्वो वसिरशनार्थेऽप्रसिद्ध इत्यत आह—अर्थशब्द इति । अशिश्च तदर्थपर इत्यपि बोध्यम् । अश्यर्थनिवृत्तिवाचकस्य वसेरित्यक्षरार्थः ॥ व्यधिकरणे इति । उक्तेर्थे सामानाधिकरण्यासम्भवादिति भावः ॥ अश्यर्थस्येति । अशिनिवृत्तेरित्यर्थः ॥ सामानाधिकरण्यायाह—अथवेति । अनयोराद्यव्याख्यैव युक्ता भाष्यस्वारस्यात् ॥

(तृतीयाक्षेपभाष्यम्)

स तर्हि वक्तव्यः ? ॥

(सिद्धान्तिसमाधानभाष्यम्)

न वक्तव्यः । नात्रोपपूर्वस्य वसेर्ग्रामोधिकरणम् । कस्य तर्हि ? । अनुपसर्गस्य । ग्रामेसौ वसंस्त्रिरात्रमुपवसतीति ॥ उपान्वध्या ॥४८॥

(प्रदीपः) नात्रेति । विशिष्टाधारावस्थितत्वेन निश्चिते देवदत्ते भोजननिवृत्तिं विशिष्टकालां प्रत्याययितुमिदं प्रयुज्यते ग्राम उपवसतीति । तत्रान्तरङ्गत्वात्प्रतीयमानवसिक्रियापेक्षो ग्रामस्याधिकरणभावः । उपवसनं तु स्वरूपेणैव कालमपेक्षत इति कालेनैवास्यान्तरङ्गः संबन्धः । ग्रामादिना तु बहिरङ्ग इत्यर्थः ॥ ४८ ॥

(उद्द्योतः) ननु कथं न तदधिकरणं ग्रामोऽत आह—विशिष्टेति ॥ अन्तरङ्गत्वादिति । ग्रामे वासाधिकरणत्वस्यैव प्रसिद्धत्वेन शीघ्रोपस्थितिकत्वरूपान्तरङ्गत्वादित्यर्थः ॥ प्रतीयमानेति । एवमुपवासाधिकरणकालेपि प्रतीयमान एवेति बोध्यम् ॥ ननु बोधकपदाभावात् कथं विशिष्टकालभुजिनिवृत्तिप्रतीतिरत आह—उपवसनं त्विति । एवकारेण नित्याकाङ्क्षा दर्शिता । तदुक्तं भाष्ये—त्रिरात्रमिति । आरम्भे त्वत्रापि द्वितीया न स्यादिति तात्पर्यम् ॥ अन्तरङ्ग इति । आवश्यक इत्यर्थः ॥ बहिरङ्ग इति । आकाङ्क्षाभावादनावश्यक इत्यर्थः ॥ असंबन्ध एवेति वक्तुं युक्तम् ॥ ४८ ॥

(१८९ कर्मसंज्ञासूत्रम् ॥ १ । ४ । ३ आ. १४ सू.)

२८९ कर्तुरीप्सिततमं कर्म ।१।४।४९॥

(तमग्रहणप्रयोजनाधिकरणम्)

(आक्षेपभाष्यम्)

तमग्रहणं किमर्थम् ? ॥

(प्रदीपः) कर्तुरीप्सित॥४९॥तमग्रहणमिति । असत्यपि तमग्रहणे ग्रामं गच्छतीत्यादौ कर्मसंज्ञा सिध्यतीप्सिततमस्यापीप्सितत्वसद्भावादिति प्रश्नः ॥

(उद्द्योतः) कर्तुरी ॥ ४९ ॥ असत्यपीति । अव्याप्तिर्नास्तीति भावः ॥

(आक्षेपबाधकभाष्यम्)

'कर्तुरीप्सितं कर्म' इतीयत्युच्यमाने इहाग्नेर्माणवकं वारयतीति माणवकेऽपादानसंज्ञा प्रसज्येत ॥

(प्रदीपः) माणवक इति । विशेषविहितत्वादपादानसंज्ञायाः ।

(उद्द्योतः) विशेषेति । अनवकाशत्वादित्यर्थः ॥

(आक्षेपसाधकभाष्यम्)

नैष दोषः । कर्मसंज्ञात्र बाधिका भविष्यति ॥

(प्रदीपः) कर्मसंज्ञेति । परत्वात् ॥

(समाधानभाष्यम्)

अग्नावपि तर्हि बाधिका स्यात् । इह पुनस्तमग्रहणे क्रियमाणे तदुपपन्नं भवति यदुक्तं *वारणार्थेषु कर्मग्रहणानर्थक्यं कर्तुरीप्सिततमं कर्मेति वचनाद्* इति ॥

(प्रदीपः) अग्नावपीति । अग्निमाणवकयोरीप्सितत्वसद्भावात् । कर्मापादानसंज्ञाविषयविभागाज्ञानपरमेतत्, न तु निरवकाशाप्यपादानसंज्ञा सावकाशया कर्मसंज्ञया बाधितुं शक्यते । तमग्रहणे तु सति संज्ञयोर्विषयविभागलाभः ॥

(उद्द्योतः) विषयविभागाज्ञानेति । अग्नावेव कर्मसंज्ञा माणवक एवापादानत्वमित्यपि स्यादिति भावः ॥ तमग्रहणे त्विति । तथथा तथा वारणार्थानामिति सूत्रे उपपादितम् ॥

(ओदनादीनां निर्वर्त्यत्वसाधनाधिकरणम्)

(आक्षेपभाष्यम्)

इहोच्यते—ओदनं पचतीति यथोदनः पच्येत द्रव्यान्तरमभिनिर्वर्तेत ॥

(प्रदीपः) इहेति। लोकः शास्त्रं च सामान्येन निर्दिश्यते। लोके प्रयुज्यमानत्वात्, शास्त्रे चोदाह्रियमाणत्वात्॥ द्रव्यान्तरमिति। ओदनशब्दस्य तण्डुलविकारे प्रयुज्यमानत्वात्पचेश्च विक्लित्त्युपसर्जनविक्लेदनवचनत्वान्निर्वृत्तस्यौदनस्य विक्लेदनान्तरकरणात्॥

(उद्द्योतः) ननु लोकेपि तथा व्यवहारादिहेत्ययुक्तमत आह—लोकः शास्त्रं चेति॥ नन्वोदनपाके कथं द्रव्यान्तरस्योत्पत्तिरत आह—ओदनशब्दस्येति। भाष्ये—यद्योदनः पच्येतेत्यस्यौदनकर्मकः पाको यदि बुध्येतेत्यर्थः॥ द्रव्यान्तरमभिनिर्वर्तेतेत्यस्य च द्रव्यान्तराभिनिर्वृत्तिः प्रतीयेतेत्यर्थः॥ विक्लेदनान्तरकरणादिति। विक्लेदनान्तरप्रतीतिप्रसङ्गादित्यर्थः॥

(समाधानभाष्यम्)

नैष दोषः। तादर्थ्यात्ताच्छब्द्यं भविष्यति। ओदनार्थास्तण्डुला ओदन इति॥

(प्रदीपः) ओदनार्था इति। गौणार्थाश्रयणेनैवं सर्वलोकस्य प्रयोगदर्शनादिदमत्र न चोदनीयम्—मुख्यस्यैव त्वोदनस्य पुनर्विक्लित्तिकरणे कस्मादयं प्रयोगो न भवतीति। विकारविशेषप्रतिपादनाय गौणार्थपरिग्रहः। तण्डुलान्पचतीत्युक्ते विकारान्तरमपि प्रतीयते॥

(उद्द्योतः) ननु गौणार्थेन प्रयोगे किं फलमत आह—विकारेति। ओदनस्वरूपेत्यर्थः॥ विकारान्तरं, भर्जनादिरूपं विक्लित्तिपदेन च पाकफलमात्रमुच्यते॥

(आक्षेपभाष्यम्)

अथेह कथं भवितव्यम्—तण्डुलानोदनं पचतीति, आहोस्वित्—तण्डुलानामोदनं पचतीति?॥

(प्रदीपः) अथेहेति। उभयथा प्रयोगदर्शनात्प्रकृतिविकृत्योः साक्षादुपादानात्तादर्थ्यात्ताच्छब्द्यानुपपत्त्या विक्लेदनवचने तु पचौ तण्डुलानामोदनं पचतीति प्रयोगायोगाद् द्रव्यान्तरनिर्वृत्तिप्रत्ययप्रसङ्गाच्च। निर्वर्तनवचने तु पचौ तण्डुलानां कर्मभावाघटनात्तण्डुलानोदनं पचतीति प्रयोगाभावप्रसङ्गाच्च प्रश्नः॥

(उद्द्योतः) ननूभयविधव्यवहाराछ्प्रयोगद्वयेनापि भाव्यमेवेति केन प्रयोगेन भाव्यमित्यर्थकप्रश्नानुपपत्तिरत आह—प्रकृतीत्यादि। कर्मभावाघटनादिति। नहि तत्र तण्डुला निष्पाद्यन्ते इति भावः॥

(समाधानभाष्यम्)

उभयथापि भवितव्यम्। कथम्?। इह हि तण्डुलानोदनं पचतीति द्व्यर्थः पचिस्तण्डुलान्पचन्नोदनं निर्वर्तयतीति॥ इहेदानीं तण्डुलानामोदनं पचतीति द्व्यर्थश्चैव पचिर्विकारयोगे षष्ठी तण्डुलविकारमोदनं निर्वर्तयतीति॥

(प्रदीपः) द्व्यर्थः पचिरिति। विक्लेदनोपसर्जने निर्वर्तने पचिर्वर्तते। तण्डुलान्विक्लेदयन्नोदनं निर्वर्तयतीत्यर्थः। तत्रोपसर्जनविक्लेदनक्रियापेक्षं तण्डुलानां कर्मत्वम्। प्रधानभूतक्रियापेक्षं त्वोदनस्य॥ द्व्यर्थश्चैवेति। तण्डुलानां संबन्धिनं विकारविशेषमोदनं विक्लित्त्या निर्वर्तयतीत्यर्थः। सा च विक्लित्तिः सामर्थ्यात्तण्डुलानामेवेति विज्ञायते॥

(उद्द्योतः) ननु फलव्यापारावादाय सर्वस्यापि द्व्यर्थत्वं नापि तावतोक्तप्रयोगोपपत्तिरत आह—विक्लेदनेति। निर्वर्तनरूपद्वितीयार्थमादाय द्व्यर्थत्वमिति भावः॥ विक्लित्त्या निर्वर्तयतीति। विक्लित्तिविशिष्टं निर्वर्तनं पचेरर्थः। वैशिष्ट्यं च क्वचित् सामानाधिकरण्येन क्वचित्करणत्वेन। विक्लित्तिशब्देनात्र विक्लेदनमेव। एवं च तण्डुलानां धात्वर्थफलाश्रयत्वाविवक्षणान्न द्वितीयेत्यर्थः। षष्ठी त्वोदनयोगे इति भावः॥ नन्वेवं विक्लित्तेः संबन्ध्याकाङ्क्षाऽनिवृत्तेत्यत आह—सा चेति॥ ननु पूर्वोक्तेर्थेपि मातुः स्मरतीतिवत् कर्मणः शेषत्वेन षष्ठीप्रयोगसिद्धेर्विकारयोगे षष्ठीति भाष्यमनुपपन्नमिति चेन्न। ओदनस्य संबन्ध्याकाङ्क्षासत्त्वेन क्रियायाश्च तदनाकाङ्क्षत्वेन तथोक्तेः, षष्ठ्यन्तस्य स्वाकाङ्क्षस्वान्वययोग्यनामसमभिव्याहारे तत्रैवान्वय इत्युत्सर्गतो व्युत्पत्तेश्चेति दिक्॥

(आपत्तिवारणाधिकरणम्)

(आक्षेपभाष्यम्)

इह कश्चित्कंचिदामन्त्रयते—सिद्धं भुज्यतामिति। स आमन्त्र्यमाण आह—प्रभूतं भुक्तमस्माभिरिति। आमन्त्र्यमाण आह—दधि खलु भविष्यति पयः खलु भविष्यति। आमन्त्र्यमाण आह—दध्ना खलु भुञ्जीय पयसा खलु भुञ्जीयेति। अत्र कर्मसंज्ञा प्राप्नोति। तद्धि तस्येप्सिततमं भवति॥

(प्रदीपः) इह कश्चिदिति। अन्वयव्यतिरेकाभ्यां दधिपयसोरीप्सिततमत्वं न त्वोदनस्येति दर्शयति॥

(उद्योतः) ईप्सिततमत्वमिति। ईप्सितशब्दोभिप्रेतपरो रूढ इति पूर्वपक्ष्याशयः॥

(समाधानभाष्यम्)

तस्याप्योदन एवेप्सिततमः। न तु गुणेष्वस्यानुरोधः। तद्यथा—भुञ्जीयाहमोदनं यदि मृदुविशदः स्यादिति। एवमिहापि दधिगुणमोदनं भुञ्जीय पयोगुणमोदनं भुञ्जीयेति॥

(प्रदीपः) तस्याप्योदन इति। दधिपयसोस्तु संस्कारकत्वात्करणभावः॥ न तु गुणेष्विति। गुणेषूपकारकेषु केवलेषु नास्यादरः, किं तर्हि तत्संस्कृत ओदन इत्यर्थः॥ मृदुविशद इति। मृदुश्चासौ विशदश्चेति कर्मधारयः। यदि मार्दवमात्रे आदरः स्यात्पङ्कमपि भक्षयेत्। विशदमात्रादरे सिकता अपि॥

(उद्द्योतः) ननूद्देश्यत्वाद् दध्यादि ईप्सिततममत आह—दधीति। संस्कारकत्वेनैव तदुद्देश्यम्, न तु साक्षात् फलाश्रयत्वेनेत्यर्थः। अन्यथा दधिपयोमात्रभोजनेनापि कृती स्यात्॥ ननु

गुणेष्वादराभावे दधिसत्ताज्ञानात्पूर्वमपि प्रवृत्तिः स्यादत आह—**केवलेष्वपि । मृदुविशद इति** । द्वन्द्वे प्रयोगानुपपत्तिरत आह—**कर्मधारय इति ॥ यदीति** । एवं च यथा तत्र तथागुणविशिष्ट ओदन एवेप्सितः । एवमिहापि दध्यादिविशिष्ट ओदन ईप्सित इति भावः ॥ अत्रेदं बोध्यम्—**तस्याप्योदन एवे**त्याद्युत्तरं क्रियाशब्दोयमित्याशयेनैव । ओदन एव फलाश्रयत्वविवक्षा, न तु गुणे दध्यादौ तन्मात्रेऽनुरोधः फलाश्रयत्वविवक्षेत्यक्षरार्थः । दृष्टान्तेऽसम्भवात्तदविवक्षा, दार्ष्टान्तिके ऐच्छिकीति भेदः । ईप्सिततमत्वं वारणार्थसन्नोक्तरीत्या तद्धात्वर्थफलवत्त्वेनेच्छाविषयत्वरूपमेव भाष्यसंमतम् । अन्यथा विशिष्टस्याभिप्रेतत्वे विशेषणस्याभिप्रेतत्वात्समाधानानुपपत्तिः । पञ्चकस्य प्रातिपदिकार्थत्वात् ॥ उभयविवक्षायां तु परत्वात्कर्मत्वमेव सत्यभिधाने आकडारसूत्रे * करणं पराणि * इत्यस्यासिद्धिछिनत्तीति कर्तृसंज्ञाविषये एवोदाहरणदानात्तदभिधानसंदेह इति नास्य तदा तमपा कर्मत्ववारणमुचितम् ॥ नवीनग्रन्थास्तु चिन्त्या एव, क्रियाशब्दत्वेपि सनेष्यमाणत्वस्यापि गर्भीकरणात् ॥

(अनुपपत्तिवारणाधिकरणम्)

(१०९८ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ ईप्सितस्य कर्मसंज्ञायां निर्वृत्तस्य कारकत्वे कर्मसंज्ञाप्रसङ्गः क्रियेप्सितत्वात् ॥ * ॥

(भाष्यम्) **ईप्सितस्य कर्मसंज्ञायां निर्वृत्तस्य कारकत्वे कर्मसंज्ञा न प्राप्नोति । गुडं भक्षयतीति । किं कारणम् ? । क्रियेप्सितत्वात् । क्रिया तस्येप्सिता ॥**

(प्रदीपः) **ईप्सितस्येति** । ईप्सिततममेवेप्सितपदेन सामान्यशब्देन निर्दिष्टम् । विशेषेषु सामान्यस्य भावात् । तत्र यन्निर्वृत्तं क्रिययाऽनाधेयविकारं क्रियाया निष्पत्त्यर्थं केवलमुपादीयते तत्क्रियासंबन्धात् प्राप्यमपि नेप्सितमिति तस्य कर्मसंज्ञा न प्राप्नोति । यत्र हि कर्मार्था क्रिया निष्पत्तिसंस्कारप्रतिपत्तिभिस्तत्र कर्मेप्सितम् । अन्यत्र तु क्रियैव प्रतीयमानसंदर्शनादिक्रियापेक्षयेप्सितेति भावः ॥ **गुडं भक्षयतीति** । भक्षणाय गुडस्योपादानं न तु गुडाय भक्षणानुष्ठानम् ॥

(उद्द्योतः) शङ्कते—भाष्ये—**ईप्सितस्येत्यादि** । नन्वीप्सिततमस्य कर्मत्वादीप्सितस्येत्यनुवादोऽयुक्तोऽत आह—**ईप्सिततममेवेति** । तमस्यान्यार्थत्वमभिप्रेत्य तावत एवोल्लेख इत्यन्ये ॥ ननु निर्वृत्तस्यापि काष्ठादेर्विकार्यस्येप्सिततमत्वं विकारवत्तयाऽस्त्येवेत्यत आह—**अनाधेयविकारमिति** । **प्राप्यमपीति** । क्रियाजन्यसंयोगादिरूपफलाश्रयमपीत्यर्थः । **नेप्सितं**, नाभिप्रेतम् । **निष्पत्तिसंस्कारप्रतिपत्तीति** । **निष्पत्तिः**, कटादेः । **संस्कारः**, प्रोक्षणादिना व्रीह्यादेः । **प्रतिपत्तिः**दाहादिना हविरादेः ॥ ननु कर्तृक्रिययाप्तुमिष्यमाणं कर्मेत्यर्थस्तत्र कथं क्रिया स्वात्मनेप्सिता भवेद् । एवं च **क्रिया तस्येप्सिते**ति भाष्यमनुपपन्नमत आह—**प्रतीयमानसंदर्शनादीति** । तज्जन्यारम्भक्रियापेक्षयेत्यर्थः ॥ ननु गुडभक्षणस्येप्सितत्वे गुडोपि तथेत्यत आह—**भक्षणायेति** । भक्षणक्रियोत्पत्त्यर्थमित्यर्थः ॥

(१०९९ समाधानवार्तिकम् ॥ २ ॥)

॥ * ॥ न वोभयेप्सितत्वात् ॥ * ॥

(भाष्यम्) **न वा एष दोषः । किं कारणम् ? । उभयेप्सितत्वात् । उभयं हि तस्येप्सितम् ॥ आतश्चोभयम् । यस्य हि गुडभक्षणे बुद्धिः प्रसक्ता भवति नासौ लोष्टं भक्षयित्वा कृती भवति ॥**

(प्रदीपः) **न वेति** । गुडभक्षणं यस्येप्सितं तस्य गुडो भक्षणक्रिययेप्सितः । यस्मान्नासौ गुडस्य दर्शनस्पर्शनादिना कृती भवति नापि लोष्टादिभक्षणेनेति न भक्षणमात्रमीप्सितं नापि गुडमात्रमित्यर्थः ॥

(समाधानबाधकभाष्यम्)

यद्यपि तावदत्रैतच्छक्यते वक्तुम् । ये त्वेते राजकर्मिणो मनुष्यास्तेषां कश्चित्कंचिदाह—कटं कुर्विति । स आह—नाहं कटं करिष्यामि घटो मया आहृत इति । तस्य क्रियामात्रमीप्सितम् ॥

(प्रदीपः) **ये त्वेत इति** । ते हि यां कां चित् क्रियामनुष्ठाय कालमतिवाहयन्ति न तेषां द्रव्यविशेषे तात्पर्यम् । ततश्च **नाहं कटं करिष्यामी**त्यत्र कटस्य कर्मत्वानुपपत्त्या द्वितीया न प्राप्नोतीति कटकर्मिका क्रिया न निषिद्धा भवेत् । तथा **घटो मयाऽऽहृत** इत्यत्र घटस्य कर्मत्वाभावादाहृत इत्यत्र कर्मणि निष्ठा न प्राप्नोति ॥

(उद्द्योतः) शङ्कते—भाष्ये—**ये त्वेत इति** ॥ ननु क्रियामात्रेप्सायां हस्तचालनमात्रेणापि तिष्ठेयुरत आह—**यां कांचिदिति** । स्वाम्यभिमतामित्यर्थः । वेतनग्रहणे तात्पर्यात् ॥ **ततश्चेति** । कटस्यानिष्यमाणत्वात् । तच्च **नाहं करिष्यामीति** शब्देन प्रतिपादितम् । आहरणक्रियया च घटे निष्पाद्यत्वाभावः स्पष्ट एव आहरणकर्तुरभिप्रेतत्वाभावश्चेति घटस्य कटस्य च तत्त्वाभाव एवेति भावः ॥

(समाधानसाधकभाष्यम्)

यद्यपि तस्य क्रियामात्रमीप्सितं, यस्त्वसौ प्रेषयति तस्योभयमीप्सितमिति ॥ कर्तुरीप्सिततमम् ॥ ४९ ॥

(प्रदीपः) **यस्त्वसौ प्रेषयतीति** । प्रयोजकचित्तानुवर्तनं तस्य स्वार्थसिद्धये कर्तव्यम् । यदा च विशिष्टकर्मिका क्रिया तेन संपाद्यते तदाज्ञानुष्ठिता भवतीति प्रयोजकवत्प्रयोज्यस्याप्युभयमीप्सितमिति भाष्यकारस्याभिप्रायः ॥ अन्ये तु प्रयोजककर्त्रपेक्षया प्रयोज्यस्य कर्तुरनीप्सितमपि कर्मेत्याचक्षते ।

तत्तु प्रयोजकव्यापारस्याशब्दार्थत्वात्पूर्वोक्तोदाहरणेऽयुक्तमिति न्यायविदो मन्यन्ते ॥ ४९ ॥

(उद्द्योतः) समाधत्ते—यद्यपि तस्येत्यादिना। ननु प्रेषयितुरुभयेप्सायामपि न प्रेष्यस्येति तदीयप्रयोगे तयोः कर्मत्वानापत्तिस्तथैवेत्यत आह—प्रयोजकेत्यादि। स्वार्थो वेतनलाभः॥४९॥

(१९० कर्मसंज्ञासूत्रम् ॥ १।४।३ आ. १५ सू.)

२९० तथा युक्तं चानीप्सितम् ॥ ५०॥

(उद्द्योतः) तथा युक्तम् ॥ ५० ॥ तथेति भिन्नं पदम्। ईप्सिततमवत्क्रियाजन्यफलाश्रय इत्यर्थः ॥

(उदाहरणनिर्णयाधिकरणेऽनुयोगभाष्यम्)

किमुदाहरणम्?॥

(उद्द्योतः) भाष्ये—किमुदाहरणमिति। पूर्वेण सिद्धिं मन्वानस्य प्रश्नः॥

(समाधानभाष्यम्)

विषं भक्षयतीति ॥

(समाधानबाधकभाष्यम्)

नैतदस्ति। पूर्वेणाप्येतत्सिध्यति ॥

(समाधानसाधकभाष्यम्)

न सिद्ध्यति। 'कर्तुरीप्सिततमं कर्म' इत्युच्यते कस्य च नाम विषभक्षणमीप्सितं स्यात् ॥

(प्रदीपः) तथायुक्तम् ॥ ५० ॥ कस्य च नामेति। विषमिति वक्तव्ये विषभक्षणमिति किमर्थमुच्यते। यदि भक्षणमीप्सितं तदा विषमपीप्सितं विषभक्षणस्य त्वनीप्सितत्वे विषमपि प्राणहरत्वादनीप्सितं भवति। भक्षणक्रियया च विषं नेप्सितं परिहारादिक्रियापेक्षया तदीप्सितं भवत्येवेति भक्षणग्रहणेन प्रदर्श्यते ॥

(उद्द्योतः) कस्य च नामेति। स्वनेच्छाविषयत्वस्य बोधनात् प्रश्नः॥ तदा विषमपीति। कर्मत्वानालिङ्गितभक्षणस्याभावादित्यर्थः॥

(समाधानबाधकभाष्यम्)

विषभक्षणमपि कस्यचिदीप्सितं भवति। इह य एष मनुष्यः दुःखार्तो भवति सोऽन्यानि दुःखान्यनुनिशम्य विषभक्षणमेव ज्यायो मन्यते ॥ आतश्चेप्सितं यत्तद्भक्षयति ॥

(प्रदीपः) विषभक्षणमपीति। यथा लोकस्य सुखप्राप्त्यर्था क्रियायां प्रवृत्तिस्तथा भयादिभ्यो दुःखनिवृत्त्यर्थापि विषादिष्वित्यर्थः॥

(उद्द्योतः) ननु सुखसाधने एव लोके ईप्सिततत्वं प्रसिद्धं न चेदं तथाऽत आह—यथेति। दुःखनिवृत्तिसाधनमपि तथेति भावः॥ क्रियाशब्द ईप्सितशब्दः सना तत्तत्क्रियोद्देश्यत्वमात्रमुपलक्ष्यत इत्याशयेन समाधत्ते—भाष्ये—आतश्चेति। एवं च पराधीनतया द्वेष्यमपि विषं भक्षयत्युपपन्नः प्रयोग इति भावः॥

(समाधानभाष्यम्)

यत्तर्ह्यन्यत्करिष्यामीत्यन्यत्करोति तदुदाहरणम्। किं पुनस्तत्? । ग्रामान्तरमयं गच्छन् चोरान्पश्यति अहिं लङ्घयति कण्टकान्मृद्नातीति ॥

(प्रदीपः) चोरान्पश्यतीति। विषयेन्द्रियसंबन्धसामर्थ्याद्दर्शनेनामुमनिष्टतमा अपि चोरास्तथायुक्ताः पूर्वेणासिद्धकर्मभावा अनेन कर्मसंज्ञया संबध्यन्ते ॥

(उद्द्योतः) अनिष्टतमा अपीति। अनुद्देश्या इत्यर्थः। भयजनकत्वात्। इदमपि द्वेष्यं कर्मेति भावः॥ पूर्वेणासिद्धेति। स्वनोद्देश्यत्वं विवक्षितम्। नह्येते दर्शनादिक्रियोद्देश्या इति भावः॥

(आक्षेपभाष्यम्)

इहेप्सितस्यापि कर्मसंज्ञा आरभ्यतेऽनीप्सितस्यापि। यदिदानीं नैवेप्सितं नाप्यनीप्सितं तत्र कथम्? ग्रामान्तरमयं गच्छन्वृक्षमूलान्युपसर्पति कुड्यमूलान्युपसर्पतीति ॥

(प्रदीपः) ईप्सितस्यापीति। ईप्सिततमस्यापीत्यर्थः॥

(समाधानभाष्यम्)

अत्रापि सिद्धम्। कथम्? । अनीप्सितमिति नायं प्रसज्यप्रतिषेधः ईप्सितं नेति। किं तर्हि?। पर्युदासोऽयम्। यदन्यदीप्सितात्तदनीप्सितमिति। अन्यच्चैवेदमीप्सिताद्यन्नैवेप्सितं नाप्यनीप्सितमिति ॥ तथायुक्तम् ॥ ५० ॥

(प्रदीपः) नायं प्रसज्यप्रतिषेध इति। यथाऽधर्मानृतादिभिरुत्तरपदार्थप्रतिपक्षभूतं वस्तु तत्प्रतिषेधद्वारेण प्रतिपाद्यते तथानीप्सितशब्देनापि द्वेष्यं वस्तु यदभिधीयते तदेव न गृह्यते, किं तु सर्वमीप्सितादन्यदित्यर्थः॥ ५० ॥

(उद्द्योतः) ननु प्रसज्यप्रतिषेधे ईप्सितं कर्म नेत्यर्थः स्यात्स चायुक्तः पूर्वेण कर्मत्वसंस्पर्शेऽत आह—यथेति। एवं च नायं प्रसज्यप्रतिषेध इत्यस्य नायं प्रतिपक्षवाचीत्यर्थः। प्रतिषेधस्य भावविरोधित्वात्तेन तदर्थलक्षणाद्वा। ईप्सितं नेत्यस्य च यदीप्सितप्रतिपक्षभूतं तदेव नोच्यते इत्यर्थः॥ किं तर्हीत्यादेश्च भिन्नमात्रमस्यार्थ इतीति भावः। तत्प्रतिषेधद्वारेणेति। आरोपितत्वबोधद्वारेणेत्यर्थः॥ धर्मभिन्नबोधेऽपि प्रतिपक्षभूतमेव धर्मभिन्नं गृह्यते तथात्र नेत्यर्थः॥ ५० ॥

(१९१ कर्मसंज्ञासूत्रम् ॥ १।४।३ आ. १६ सू.)

२९१ अकथितं च ॥ ५१ ॥

(अनुयोगभाष्यम्)

केनाकथितम्? ॥

(प्रदीपः) अकथितं च ॥ ५१ ॥ केनेति ॥ किं

साधारण्या कारकसंज्ञया, अथ विशेषसंज्ञाभिरपादानादिभिरिति प्रश्नः ॥

(उद्द्योतः) अकथितं च ॥ ५१ ॥ 'कथ वाक्यप्रबन्धे' इत्यस्मान्निष्पन्नः क्रियाशब्दोयम् । तत्र कथनस्य करणाकाङ्क्षत्वाद् द्वयोश्चोपस्थितत्वादाह—किमिति ॥

(समाधानभाष्यम्)

अपादानादिभिर्विशेषकथाभिः ॥

(प्रदीपः) **अपादानादिभिरिति** । कर्तरि करणे वाऽत्र तृतीया । भूतकालश्चात्र न विवक्ष्यते । यथा **पराजेरसोढ** इत्यत्रासहिष्यमाणस्याप्यपादानसंज्ञा भवति अध्ययनात्पराजेष्यत इति । तेन हेतुकर्तृसंज्ञाभ्यां कथयिष्यमाणस्यापि कर्मसंज्ञा न भवति । इह **कारक** इत्यनुवर्तनात्सत्येव कारकत्वेऽकथितस्य कर्मसंज्ञया भाव्यमिति सामर्थ्याद्विशेषकथाभिरकथितत्वमाश्रीयते । प्रश्नप्रतिवचनाभ्यां चासंकीर्तितवचनोऽकथितशब्दो, न त्वप्रधानवाची रूढिशब्दोत्राश्रित इति दर्शितम् । रूढिषु हि व्युत्पत्त्यर्थमेव क्रियोपादीयते । न तु प्रवृत्तिनिमित्तत्वेन । तथा च गच्छतीतिगौरिति व्युत्पत्तावपि यथा गच्छतीत्युक्ते केनेति प्रश्ने रथेनेति प्रतिवचनं भवति तथा गौरित्युक्ते प्रश्नप्रतिवचने न भवतः ॥

(उद्द्योतः) करणस्यापि कर्तृत्वेन विवक्षामभिप्रेत्याह—**कर्तरीति** ॥ **भूतकालश्चात्र न विवक्ष्यत इति** । तत्फलं तु निवृत्तैकप्रेषणदुहादिभ्यो णिचि दुह्यमानार्थत्वेन गत्यादिनियमात्**कर्तुरीप्सिततममित्या**यप्राप्तौ प्रयोज्यकर्तुर्गवादेः कर्तृत्वात् तदविवक्षया शुद्धजन्यत्वविवक्षायां बोध्यम् । न च प्रयोज्यस्य कर्तृत्वाविवक्षायां कर्तुः प्रयोजकत्वाभावाण्णिजनापत्तिः । अन्तरङ्गत्वात्पूर्वं णिचि ततस्तस्याविवक्षणात् तत्प्रयोजक इत्यत्र तत्पदेन स्वतन्त्रस्योपलक्षणाद्वा । अत एव ग्रामं गमयतीत्यादिसिद्धिरिति भावः ॥ परं त्वत्र मानं चिन्त्यम् । किं च गत्यादिनियमेन परत्वादस्यापि बाधो दुर्वार इति दिक् ॥ **न भवतीति** क्वचित्पाठः । पूर्वोक्तविषयाभावेन कर्तृत्वविवक्षायामपि स्यात् । अधुना तु नेत्यर्थः । परया कर्तृसंज्ञया बाधाच्चिन्त्यमिदम् । **कर्मसंज्ञा भवतीति**पाठे तत्त्वाविवक्षायामित्यादिः ॥ परं तु स पाठोऽप्युक्तरीत्या चिन्त्य एव ॥ नन्वेवमपि कारकसंज्ञयाऽकथितत्वमेव किं नाश्रीयतेऽत आह—**प्रश्नेति** ॥ **न त्वप्रधानवाचीति** । तद्ग्रहणे हि दुह्यादिव्यतिरिक्तविषये सावकाशाधिकरणापादानविषये गोर्दोग्धि पय इत्यादाववधित्वविवक्षायामपि परत्वादनेन कर्मत्वापत्तिरिति भावः ॥ प्रश्नप्रतिवचनाभ्यां रूढ्यग्रहणं कथमिति व्युत्पादयति—**रूढिषु हीति** । रूढ्यात्यन्ततिरस्कारायोगार्थस्य तत्र मानमेव नास्तीति भावः ॥ न च रूढिर्योगमपहरतीतिन्यायायौगिकार्थस्यैव कथं ग्रहणं, न चानिष्टनिवारणाय तत्, लक्ष्यैकशरणानां लक्ष्यायत्तप्रमाणस्थितेरभावादिति वाच्यम् । लक्ष्यैकशरणभाष्यकारादिव्याख्यानेन तस्यैव ग्रहणादित्याहुः ॥

(उदाहरणनिर्णयाधिकरणम्)

(अनुयोगभाष्यम्)

किमुदाहरणम्? ॥

(प्रदीपः) **किमुदाहरणमिति** । नटस्य शृणोतीत्यादावपि कर्मसंज्ञाप्रसङ्ग इति प्रश्नः ॥ अथवाऽपादानादिभिः सर्वस्य विषयस्य व्यापनादुदाहरणासंभवं मत्वा पृच्छति ॥

(उद्द्योतः) अथ चेत्यादि चिन्त्यम् । नटस्य शृणोतीत्यादेः संभवात् । नटान्निःसरन्तं शब्दं शृणोतीत्यर्थे तूपयोगे इत्यस्य वैयर्थ्यापत्त्याऽनभिधानेन तस्य प्रयोगस्याभावात् । अत एव प्रत्याख्यानेन फलैक्यसिद्धिः ॥

(समाधानभाष्यम्)

दुहियाचिरुधिप्रच्छिभिक्षिचिञामुपयोगनिमित्तमपूर्वविधौ ॥

ब्रुविशासिगुणेन च यत्सचते तदकीर्तितमाचरितं कविना ॥ १ ॥

(प्रदीपः) **उपयोगनिमित्तमिति** । उपयुज्यत इत्युपयोगः पयःफलादि तस्य निमित्तं गवादि । अनेन गां दोग्धि पय इत्यत्र पयस उपयुज्यमानत्वादीप्सिततमत्वम्, गोस्तु पयोर्थत्वादपादानस्यानीप्सिततमत्वं दर्शयति । तथायुक्तत्वाभावाच्च **गोस्तथायुक्तमि**त्यनेनापि कर्मसंज्ञा न सिध्यति ॥ **अपूर्वविधाविति** । **पूर्वत्व**मन्यत्वोपलक्षणमिति परविधावपीयं संज्ञा न भवति ॥ **ब्रुविशासिगुणेनेति** । ब्रुविशास्योर्गुणः साधनं प्रधानकर्म धर्मादिकं तेन च यत्सचते संबध्यत इत्यर्थः । क्रियायाः साध्यत्वात्प्राधान्यं तदर्थत्वात्प्रवृत्तेः, कारकाणां गुणत्वम् ॥ **कविनेति** । कविशब्दो मेधाविवचनः क्रान्तदर्शनात् ॥ दुह्यादीनां चार्थोपलक्षणायोपादानात्पर्यायप्रयोगेपि कर्मसंज्ञा भवति ॥ ननु गां दोग्धि पय इत्यस्यायमर्थः—गौः पयस्त्यजति, देवदत्तो गवा पयस्त्याजयति । तत्र प्रयोजकव्यापारेणाप्यमानत्वाद्गोः कर्मत्वं सिद्धम् । नैतदस्ति । यथा ण्यन्तेषु धातुषु क्रियाविष्टः प्रयुज्यत इति प्रतीतिः । नैवमिह । निष्क्रयस्यापि गवादेर्दोहनादिषु विनियोगात् ॥

(उद्द्योतः) **तस्य निमित्तमिति** । कर्मनिष्ठधात्वर्थविशिष्टस्य कर्मणो निमित्ततया संबन्धीत्यर्थ इति वदन्ति । स्पष्टमिदं सूत्रशेषे भविष्यति । एतत्फलं तु करणभूतपाण्यादिनिवृत्तिः । तस्य दोग्धृव्यापारजनकतयान्यथासिद्धत्वेन विभागविशिष्टपयोरूपकर्मणोऽनिमित्तत्वात् ॥ यत्तु वृत्तिकृता तस्याप्युपयोगनिमित्तत्वमुपेत्यापूर्वविधावित्यनेन वारणं कृतम्—विहिता तत्र करणादिसंज्ञेति ॥ तत्र, गवादीनामपादानत्वाद्यविवक्षायामिवास्यापि करणत्वाद्यविवक्षायां कर्मत्वापत्तेर्दुर्वारत्वात् । उपयोगपदेन मुख्यं कर्मेत्युक्तम्, **तस्य निमित्त**मित्यनेन धात्वर्थव्यापाराङ्गत्वं तत्संबद्धत्वमुक्तम् । **अन्ववरुणद्धि गां व्रजमि**त्यत्रापि पुनर्निर्गमप्रतिबन्धेन स्थितिस्थैर्यमर्थः । एवं च तत्र प्रतिबन्धानुकूलव्यापाराङ्गं व्रजस्य गोसंबन्धोस्त्येव । उपयो-

गसाहचर्यांच्चाग्रे गुणपदेनाप्यस्यैव ग्रहणम्। तेन संबध्यते धात्वर्थव्यापारानन्तरमित्यर्थ इहव:॥ **अनीप्सिततमस्त्वं दर्शयतीति।** इदं च विभागजन्यबहिर्देशसंयोगानुकूलव्यापारार्थत्वे दुहधातोर्बोध्यम्। यदा तु त्याजनाऽर्थस्तदा प्रयोजकव्यापारेणेप्सिततमत्वमस्त्येवेति बोध्यम्। इदं चाकडारसूत्रभाष्ये ध्वनितम्॥ **तथायुक्तत्वाभावाच्चेति।** फलाश्रयत्वाभावादित्यर्थः॥ **अपूर्वविधाविति।** कर्मसंज्ञापेक्षया पूर्वसंज्ञानां विधिविषयाभाव इत्यर्थः॥ यद्वैतद्विधेयकर्मसंज्ञापेक्षया पूर्वसंज्ञाविषयाभाव इत्यर्थ इति॥ तन्न। अनेन वा पूर्वेण वा कर्मत्वे विशेषाभावात्॥ न च पूर्वविषयकर्मत्वाविवक्षायां कर्मत्वार्थमिदं षष्ठ्यपवादः। एवं च संबन्धत्वेन बोधार्थमिदमिति वाच्यम्। सर्वसूत्रबोधिते कर्मसंज्ञकेऽर्थे विहितप्रत्ययानां कर्मत्वशक्त्यैव कर्मबोधकत्वात्। किं च कर्तुरित्याद्यपि षष्ठ्यपवाद एव, तदभावे तद्विषये षष्ठ्या एव प्राप्तेः। अनेनापादानत्वाविवक्षायां सर्वथा तदप्राप्तौ वा गवादेर्जनकत्वसमानाधिकरणशक्तिविशेषणान्वयविवक्षायामनेन कर्मत्वं भवतीत्युक्तम्॥ **परविधावपीत्याद्युक्तमुक्तरीतेः॥ गुणः साधनमिति।** क्रियानिरूपितं शाब्दं गुणत्वम्। आर्थं तूद्देश्यत्वात्प्राधान्यमिति बोध्यम्॥ **सचत इति।** धात्वर्थव्यापारादनन्तरमिति शेषः॥ **षच सेचने** इत्यतोऽनुदात्तेतः संवध्नातेः कर्मव्यापारे वर्तमानादात्मनेपदम्। **षच समवाये** इत्ययं तु परस्मैपदी॥ भाष्ये **आचरितं** व्यवहृतमित्यर्थः॥ **क्रान्तदर्शनादिति।** क्रान्तदर्शनत्वादित्यर्थः। **कविः क्रान्तदर्शनो भवतीति** निरुक्तादिति भावः। क्रान्तानि दर्शनानि येनेति विग्रहः। स चात्र पाणिनिरिति बोध्यम्॥ **अर्थोपलक्षणायेति।** अत एव **शकारमसि चोदित** इति **परस्मैपदाना**मितिसूत्रे भाष्ये पृच्छिपर्यायस्य चुदेर्द्विकर्मकप्रयोगः संगच्छते॥ केचित्तु चुदेर्व्यापारद्वयार्थत्वे कर्तुरित्यनेन द्विकर्मकत्वे प्रधानव्यापारजन्यफलाश्रयत्वेन प्रधानकर्मणि क्तेनोक्तप्रयोगोपपत्तेरर्थपरत्वे मानं चिन्त्यमित्याहुः॥ **गवा पय इति।** इदं चिन्त्यम्। त्याजितैः फलमुत्खातैरित्यादिप्रयोगात्

"तारेर्ग्राहेस्तथा मोचेस्त्याजेर्दापेश्च संग्रहः।
कारिकायां चशब्देन सुधाकरमुखैः कृतः॥"

इत्युक्तेश्च गत्यादिसूत्रे एषामुपसंख्यानावश्यकतया कर्तरि तृतीयाया दुर्लभत्वादिति केचित्॥ वस्तुतस्तु भाष्यानुक्तत्वेन गमकाभावेन च **गत्यादिसूत्रे** नोपसंख्यानम्। त्याजितैरित्यादिप्रयोगाश्च चिन्त्या एव कैयटस्वरसादित्याहुः॥ **सिद्धं कर्मत्वमिति। कर्तुरीप्सिततम**मित्यनेन॥ **निष्क्रियस्यापीति।** तद्व्यापाराप्रतीतावपि दोहनादिविषयेऽस्य प्रयोगादित्यर्थः। एवं च विभागजन्यसंयोगानुकूलव्यापारमात्रस्य धात्वर्थत्वे गोरवधित्वात्तदविवक्षायामिदमावश्यकमिति भावः॥

(उदाहरणभाष्यम्)

दुहि—गां दोग्धि पयः॥

(प्रदीपः) **गां दोग्धीति।** दोहेनाप्यमानत्वेपि गोरीप्साप्रकर्षाभावात्तमप उपादानात्प्रकर्षस्य विवक्षितत्वादप्राप्ता कर्मसंज्ञाऽनेन विधीयते। दुह्यादिपरिगणनाभ्दटस्य शृणोतीत्यादौ न भवति॥

(उद्द्योतः) **दोहेनाप्यमानत्वेपीति।** दुहधात्वर्थगोपनिष्ठव्यापारजन्यगोनिष्ठव्यापाररूपफलाश्रयत्वेपीत्यर्थः॥ **ईप्साप्रकर्षेति।** विभागजन्यसंयोगानुकूलव्यापारानुकूलव्यापारस्य दुहर्थत्वे इदम्। उद्देश्यत्वाभावाद् व्यापारद्वयजन्यफलाश्रयत्वाभावाच्च तत्तु पयस्येवेति भावः॥ **अप्राप्तेति। तथा युक्त**मित्यपि न ईप्सितत्वस्य सत्त्वेनानीप्सितत्वाभावादिति बोध्यम्॥ चिन्त्यमिदम्। **गां दोग्धि पयः परत्वात्कर्तुरीप्सिततममिति कर्म**त्वमित्याकडारसूत्रस्थभाष्यविरोधात्। तत्र सूत्रे धातूपात्तफलाश्रयत्वरूपस्यैवेप्सिततमत्वस्य ग्रहाच्च। तस्मात्पयोनिष्ठविभागजसंयोगानुकूलव्यापारस्यैव धात्वर्थत्वे इदं भाष्यमिति तत्त्वम्। एवमग्रेपि। एवंरूपेर्थेऽपादानत्वाविवक्षाभिप्रायेण सिद्धान्तिन उदाहरणदानम्, तदजानतः पूर्वपक्षिणः खण्डनमित्येव सारम्॥ किं च तण्डुलानोदनं पचतीत्यत्र द्व्यर्थत्वेन द्वयोरपि **कर्तुरि**त्येव कर्मत्वमिति तत्सूत्रस्थभाष्यविरोधः। त्वद्रीत्या गवीव तण्डुलेष्वपीप्साप्रकर्षाभावात्॥

(उदाहरणत्वबाधकभाष्यम्)

नैतदस्ति। कथिताऽत्र पूर्वापादानसंज्ञा॥ दुहि॥

(प्रदीपः) **कथितात्रेति।** गोः पय आदत्त इत्यर्थावगमात्॥

(उद्द्योतः) ननु विभागजसंयोगानुकूलव्यापारानुकूलव्यापारार्थकत्वेऽपादानत्वाप्राप्तेराह—**गोः पय इति।** एवं चेदृशार्थकदुहधातुयोगेऽपादानत्वप्राप्त्याऽस्याप्रवृत्तिः। पूर्वोक्तार्थे तु सिद्धमेव कर्मत्वमिति भावः। एवमग्रेपि बोध्यम्। अत एव सिद्धाऽत्र कर्मसंज्ञेति, कथिता पूर्वा कर्मसंज्ञेति वा नोक्तम्, कर्मसंज्ञाया विधेयत्वात्तदतिरिक्तपूर्वविधेरेवापूर्वविधावित्यत्र ग्रहणौचित्यादिति तात्पर्यम्। तदविवक्षायामुदाहरणत्वं त्वसौ न जानाति॥

(उदाहरणभाष्यम्)

याचि—इदं तर्हि—पौरवं गां याचत इति॥

(प्रदीपः) **पौरवं गामिति।** पौरवेण गां दिदापयिषत इत्यर्थः प्रतीयते गोश्चेप्सिततमत्वं न पौरवस्य॥

(उदाहरणत्वबाधकभाष्यम्)

नैतदस्ति। कथितात्र पूर्वाऽपादानसंज्ञा॥

(प्रदीपः) **कथितात्रेति।** पौरवाद्गां जिघृक्षत इत्यर्थसम्प्रत्ययात्॥

(उदाहरणत्वसाधकभाष्यम्)

न याचनादेवापायो भवति। याचितोसौ यदि ददाति ततोऽपायेन युज्यते॥ याचि॥

(प्रदीपः) **न याचनादेवेति।** याचितापि याचनकाले नाध्यवस्यति नूनमस्मादिदं वस्तु निर्गत्य मां प्राप्नोतीति भावः॥

(उद्द्योतः) ननु बुद्धिकृतापायमाश्रित्य संज्ञा स्यादत आह—**याचितापीति।** एवं च बुद्धिकृतस्यापि तस्याभाव इति भावः॥

(उदाहरणभाष्यम्)

रुधि—अन्ववरुणद्धि गां व्रजम् ॥

(प्रदीपः) **अन्ववरुणद्धीति** । गौर्व्रजं प्रविशति गवा व्रजं प्रवेशयतीत्यर्थः ।

(उद्द्योतः) **गवा व्रजमिति** । बलात्कारेण प्रवेशनस्यैवावरुध्यर्थतया नायं समानार्थो रुधेरिति भावः । गौर्व्रजे तिष्ठति गां व्रजे निर्गमप्रतिबन्धेन स्थापयतीत्यर्थाभिप्रायेणैवोदाहरणमधिकरणत्वाविवक्षाभिप्रायेण ॥

(उदाहरणत्वबाधकभाष्यम्)

नैतदस्ति । कथितात्र पूर्वाधिकरणसंज्ञा ॥ रुधि ॥

(प्रदीपः) **कथितेति** । गां व्रजे स्थापयतीति सम्प्रत्ययाद् व्रजस्य स्थानक्रियापेक्षमाधारत्वम् ॥

(उद्द्योतः) तदजानतस्तु खण्डनं पूर्ववत् ॥

(उदाहरणभाष्यम्)

प्रच्छि—माणवकं पन्थानं पृच्छति ॥

(प्रदीपः) **माणवकमिति** । आचिख्यापयिषति पन्थानं माणवकेनेत्यर्थः ॥

(उदाहरणत्वबाधकभाष्यम्)

नैतदस्ति । कथितात्र पूर्वापादानसंज्ञा ॥

(प्रदीपः) **कथितेति** । माणवकान्मार्गोपदेशं जिघृक्षत इति सम्प्रत्ययात् ॥

(उदाहरणत्वसाधकभाष्यम्)

न प्रश्नादेवापायो भवति । पृष्टोऽसौ यद्याचष्टे ततोऽपायेन युज्यते ॥ प्रच्छि ॥

(प्रदीपः) **न प्रश्नादेवेति** । प्रश्नमात्रमनङ्गीकृतापायं धात्वर्थ इत्यर्थः ॥

(उद्द्योतः) बुद्धिकृतोप्यपायो नास्तीत्याह—**प्रश्नमात्रमिति**। एवं च प्रश्नस्य विश्लेषाजनकत्वेन पृच्छिं प्रति माणवकस्यापादानत्वं न प्रसक्तमिति भावः ॥

(उदाहरणभाष्यम्)

भिक्षि—पौरवं गां भिक्षते ॥

(उदाहरणत्वबाधकभाष्यम्)

नैतदस्ति । कथितात्र पूर्वाऽपादानसंज्ञा ॥

(उदाहरणत्वसाधकभाष्यम्)

न भिक्षणादेवापायो भवति भिक्षितोसौ यदि ददाति ततोऽपायेन युज्यते ॥ भिक्षि ॥

(प्रदीपः) **भिक्षिर्याचिवद्व्याख्येयः** । अथ याचिभिक्ष्योरेकार्थत्वात् किमर्थमुभयोरुपादानम् । उच्यते—अनुनयार्थस्यापि याचेर्ग्रहणार्थम् । तेनाविनीतं विनयं याचत इत्यत्रापि कर्मसंज्ञा भवति ॥

(उद्द्योतः) **अनुनयार्थस्यापि याचेरिति** । भिक्षेरप्युभयार्थत्वेन विनिगमनाविरहाच्चिन्त्यमिदम् । किं चोभयार्थकयाचिग्रहणेनैव सिद्धे भिक्षिग्रहणमर्थग्रहणाभावे लिङ्गमेवोचितम् ॥

(उदाहरणभाष्यम्)

चिञ्—वृक्षमवचिनोति फलानि ॥

(प्रदीपः) **वृक्षमिति** । वृक्षेण त्याजयति फलानीत्यर्थः ॥

(उदाहरणत्वबाधकभाष्यम्)

नैतदस्ति । कथितात्र पूर्वाऽपादानसंज्ञा ।

(प्रदीपः) **कथितेति** । वृक्षात् फलान्यादत्त इत्यर्थावसायात् ॥

(उद्द्योतः) एवं च **वृक्षमवचिनो**तीत्यपि वृक्षात् फलान्यादत्त इत्यर्थे एवोदाहरणम् । तदविवक्षायामुदाहरणमिति तु न जानाति पूर्वपक्षी ॥

(उदाहरणभाष्यम्)

ब्रुविशास्गुणेन च यत्सचते तदकीर्तितमाचरितं कविना ॥ ब्रुविशास्गुणेन यत्सचते तच्चोदाहरणम् । किं पुनस्तत् ? । पुत्रं ब्रूते धर्मं, पुत्रमनुशास्ति धर्ममिति ।

(प्रदीपः) **पुत्रमिति** । पुत्रो धर्मं प्रतिपद्यते पुत्रं धर्मं प्रतिपादयतीत्यर्थः ॥

(उद्द्योतः) विषयतासंबन्धावच्छिन्नज्ञानानुकूलो वचनरूपो व्यापारो ब्रूञादेरर्थः ।

(उदाहरणबाधकभाष्यम्)

नैतदस्ति । कथितात्र पूर्वा संप्रदानसंज्ञा ॥

(उदाहरणोपसंहारभाष्यम्)

(प्रदीपः) **कथितेति** । धर्मेण वचनानुशासनकर्मणा पुत्रस्याभिप्रेयमाणत्वात् ॥

(उद्द्योतः) सम्प्रदानत्वाविवक्षायामुदाहरणमिति तु न जानाति, कैयटोक्तार्थे तु कर्तुरिति सिद्धमेव कर्मत्वम् ॥

तस्मात्त्रीण्येवोदाहरणानि । पौरवं गां याचते, माणवकं पन्थानं पृच्छति, पौरवं गां भिक्षते इति ।

(उद्द्योतः) भाष्ये-**तस्मात्त्रीण्येवेति**। यदि तेष्वपायाप्रतीतिस्तदा त्रीणि । अकथितत्वं च सर्वथाऽप्राप्तापादानत्वादिकमेव । याचतेश्च स्वत्वनिवृत्तिस्वस्वत्वोत्पत्त्यनुकूलो व्यापारविशेषोर्थः । तत्र स्वत्वे पौरवस्य जनकतासमानाधिकरणनिरूपकत्वेनान्वयः । पृच्छेस्तु जिज्ञासाविषयार्थज्ञानानुकूलव्यापारोर्थः । व्यापारे च माणवकस्य जनकत्वमात्रेणान्वय इत्यप्राप्तकर्मत्वार्थमिदम् । यदि तु तेष्वप्यपायप्रतीतिस्तदा तेष्वपि पूर्वविधिविषयसत्त्वात्तान्यपि नोदाहरणानि । परिगणितातिरिक्ते च तवाप्येतत्प्रवृत्तिरनिष्टेति सूत्रमिदमसङ्गतमित्येतत्तात्पर्यम् ॥

(प्रधानाप्रधानयोःप्रत्ययनिर्णयाधिकरणम्)

(आक्षेपभाष्यम्)

अथ ये धातूनां द्विकर्मकास्तेषां किं कथिते लादयो भवन्ति, आहोस्विदकथिते ? ॥

(प्रदीपः) **अथेति** । सर्वोदाहरणवाद्याचार्यं उदाहरणत्रयवादिनं स्वमतात्प्रच्यावयितुमाह । इहासङ्कीर्तितपर्यायस्या-

कथितशब्दस्य ग्रहणे विवक्षाभेदाद्गां दोग्धि पय इत्याद्यपि भवति गोर्दोग्धि पय इत्याद्यपि । पूर्वोक्ते तूदाहरणत्रये कर्मसंज्ञैवेत्येषा व्यवस्था । अप्रधानवचनाकथितशब्दोपादाने त्वपादानसम्प्रदानसंज्ञे बाधित्वा दुह्यादिषु कर्मसंज्ञैव स्यादित्यसङ्कीर्तितमकथितमिहाश्रितम् । तत्र कर्मणि लादय उत्पद्यमानाः प्राधान्याप्राधान्याभ्यां भिन्नकक्ष्यमनेकं कर्म युगपदभिधातुमसमर्थाः किं प्रधानकर्मण्युत्पद्यन्ते अथ गुणकर्मणीति प्रश्नः ॥

(उद्द्योतः) उदाहरणत्रयवादिनमिति । सूत्रासङ्गतिवादिनमित्यर्थः ॥ विवक्षाभेदादिति । अपादानत्वविवक्षायां पञ्चमी तदविवक्षायामनेन कर्मत्वमित्यर्थः ॥ कर्मसंज्ञैवेति । तन्नितययोगे सर्वदापायाप्रतीतेरिति भावः । नहि याचनादेवेत्यादेर्भाष्ये पूर्वं सिद्धान्त्युक्तित्वाद् याचितापीत्यादिना बौद्धापायाभावस्यापि स्वयं कथनादिति तात्पर्यम् ॥ एषा व्यवस्थेति । सिद्धान्तिनः संमतेति भावः ॥ अपादानसम्प्रदानसंज्ञे इति । अपादानत्वादिविवक्षायामपीति भावः ॥ अन्ववरुणद्धि गां व्रजमित्यत्राधिकरणसंज्ञाबाधस्येदमुपलक्षणम् । यदि तु व्रजोपि प्रधानं तदा तत्र नैव कर्मत्वं स्यादित्यस्योपलक्षणं बोध्यम् ॥ कर्मसंज्ञैवेति । तथा युक्तमित्यस्यात्र संबन्धो नास्तीति भावः ॥ प्रश्न इति । सर्वोदाहरणवादिन इति भावः ॥

(समाधानभाष्यम्)

कथिते लादयः ॥

(प्रदीपः) **कथित इति** । प्रधाने ईप्सिततमे इत्यर्थः । प्रधानाप्रधानसन्निधौ प्रधानस्यैवाभिधानस्य न्याय्यत्वात् ! अथ वाऽपरः कथितस्यैवाभिधानं मन्यते, अकथितस्य तु कारकत्वाभावादभिधानासम्भवमवैति । यद्वक्ष्यति **षष्ठीं कुर्यात्तदा गुणे इति** ॥

(उद्द्योतः) सूत्रासंगतिवादिन उत्तरम्—**कथित इति** । कर्तुरीप्सिततममित्यादिना कृतकर्मसंज्ञे इत्यर्थस्तद्व्याचष्टे—**प्रधाने इति** । तत्र हेतुमाह—**प्रधानेति** ॥ **कारकत्वाभावादिति** । कर्त्रादिषट्कान्यतमत्वाभावादित्यर्थः । इदं तु सूत्रं मूकमेवा**पूर्वविधा**वित्युक्तेरिति भावः ॥

(आक्षेपभाष्यम्)

कथिते लादिभिरभिहिते गुणकर्मणि का कर्तव्या ?॥

(उद्द्योतः) सर्वोदाहरणवादी एतत्सूत्रोदाहरणत्वेन संमते गुणकर्मणि का कर्तव्येतिसूत्रासंगतिवादिनं पृच्छति—**कथिते लादिभिरिति** ॥

(११०० समाधानवार्तिकम् ॥ १ ॥)

॥ * ॥ कथिते लादयश्चेत्स्युः षष्ठीं कुर्यात्तदा गुणे ॥ * ॥

(भाष्यम्) **कथिते लादयश्चेत्स्युः षष्ठी गुणकर्मणि तदा कर्तव्या । दुह्यते गोः पयः, याच्यते पौरवस्य कम्बल इति ।**

(उद्द्योतः) सूत्रासंगतिवादी किं गवादि तवापादानत्वादिना न विवक्षितमुत विवक्षितमिति विकल्प्याद्ये आह—**षष्ठीमिति** । **गुणे** तव गुणकर्मत्वेनाभिमते ॥ यदि तूदाहरणत्रयमस्य वादिनोऽभिमतं स्यात्तदा पौरवस्य याच्यते इति षष्ठीकरणमसंगतम्, अनेन कर्मत्वे शेषत्वाभावादिति बोध्यम् ॥

(आक्षेपभाष्यम्)

कथम् ?॥

(११०१ समाधानवार्तिकम् ॥ २ ॥)

॥ * ॥ अकारकं ह्यकथितात् ॥ * ॥

(भाष्यम्) **अकारकं ह्येतद्भवति ॥ किं कारणम्? । अकथितत्वात् ॥**

(प्रदीपः) **अकारकमिति** । अपादानादिष्वेव विशेषेषु कारकत्वं सामान्यं स्थितं न तु विशेषरहितस्य सामान्यस्य स्थितिरस्तीति भावः ॥

(उद्द्योतः) षष्ठ्यां हेतुमाह—**अकारकं हीति** ॥ **अकथितादिति** । भावप्रधानो निर्देशः । क्वचिदकथितत्वादित्येव पाठः । अपादानादिषड्रूपत्वाभावात्कारकशेषत्वमित्यर्थः ॥ अस्य सूत्रस्यासंगत्याऽनेन कर्मत्वस्याप्राप्तेरिति भावस्तदेवाह—**अपादानादिष्वेवेति** ॥

(११०२ व्यतिरेकवार्तिकम् ॥ ३ ॥)

॥ * ॥ कारकं चेत्तु नाकथा ॥ * ॥

(भाष्यम्) **अथ कारकं नाकथितम् ।**

(उद्द्योतः) एतदेव व्यतिरेकमुखेनोपपादयति—भाष्ये **कारकं चेत्तु नाकथेति** ॥ एवं चेदं सूत्रमसंगतमेवेति भावः । **अपूर्वविधावि**त्यस्य त्व पूर्वविधिविषयाभावे इत्येवार्थो न तु तद्विषयाविवक्षायामितीत्यभिमानः ॥

(आक्षेपभाष्यम्)

अथ कारके सति का कर्तव्या ?॥

(प्रदीपः) **अथ कारक इति** । यदा विशेषाश्रयणादस्ति सामान्यमित्यर्थः ॥

(उद्द्योतः) अपादानत्वादिरूपेण विवक्षारूपे द्वितीयपक्षे आह—**अथ कारके इति** ॥ तद्व्याचष्टे—**यदा विशेषेति** ॥ **अस्ति सामान्यमि**त्यस्य तदा का कर्तव्येतिशेषः ॥ तदा न शेषत्वमिति भावः ॥

(११०३ समाधानवार्तिकम् ॥ ४ ॥)

॥ * ॥ कारकं चेद्विजानीयाद्यां यां मन्येत सा भवेत् ॥ * ॥

(भाष्यम्) **कारकं चेद्विजानीयाद्यां यां प्राप्नोति**

स्यासा कर्तव्या । दुह्यते गोः पयः, याच्यते पौरवात्कम्बल इति ।

(प्रदीपः) यांयामिति । उद्देश एव वीप्सा प्रतिपन्नेति सा भवेदिति प्रतिनिर्देशे न विवक्षिता ॥ **दुह्यते गोरिति ।** अपादानं गौः ॥ **याच्यते पौरवादिति ।** ननूदाहरणत्रयवादी पौरवस्य कर्मत्वमिच्छत्येवेति कथं पौरवादित्युक्तम् । अत्रोच्यते—न्यायस्य समानत्वादत्राप्यपादानत्वं मन्यते । तथाहि—याच्यते पौरवात्कम्बल इत्यस्य पौरवात्कम्बल आदित्स्यत इत्यर्थः । ततो बुद्धिकृतस्यापायस्यात्र सम्भवः ॥

(उद्योतः) **कर्मत्वमिच्छत्येवेति ।** कर्मत्वमेवेच्छतीत्यर्थः ॥ **ततो बुद्धिकृतस्येति ।** एवं च सूत्रासंगतिरेवास्य मते इति भावः ॥ तस्माच्छ्रीष्येवेति भाष्यं मदुक्तरीत्या व्याख्येयम् । एवं च भाष्ये पञ्चम्युच्चारणवदेवेदं पञ्चम्युच्चारणं पूर्वपक्षिणः, । न त्वेतद्ग्रन्थसिद्धान्ते याचियोगे पञ्चम्यभिमतेति भ्रमितव्यम् । **न याचनादेवे**त्यादेः पूर्वं सिद्धान्त्युक्तित्वात् । अत **एवापादानत्वं मन्यत** इत्युक्तम् ॥

(११०४ समाधानबाधपूर्वकनियमवार्तिकम् ॥ ५ ॥)

॥ * ॥ कथितेभिहिते त्वविधिस्त्वमतिर्गुणकर्मणि लादिविधिः सपरे ॥ * ॥

(भाष्यम्) **कथिते लादिभिरभिहिते त्वविधिरेष भवति । किमिदं त्वविधिरिति ? । तव विधिस्त्वविधिः ॥ त्वमतिः । किमिदं त्वमतिरिति ? । तव मतिस्त्वमतिरिति ॥ नैवमन्ये मन्यन्ते ॥ कथं तर्ह्यन्ये मन्यन्ते ? । गुणकर्मणि लादिविधिः सपरे । गुणकर्मणि लादयो भवन्ति सह परेण योगेन "गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ" इति ।**

(प्रदीपः) **कथित इति ।** प्रधानकर्मणि लादिभिरभिहिते तवेयं मतिर्यदुक्तं गुणे षष्ठी भवति चतुर्थीपञ्चम्यौ चेति ॥ **तव विधिस्तव मतिरिति ।** अस्वपदेन विग्रहः । त्वशब्दस्त्वन्यवाची । यथोत **त्वः पश्यन्निति** पस्पशायामुक्तम् । युष्मदर्थस्यापि त्वपेक्षावशादन्यत्वमस्तीत्येवमुक्तम् ॥ इदानीं न्याय्यं पक्षं दर्शयति—**गुणकर्मणीति ॥ लादयो** लकृत्यक्तखलर्थाः । गौर्दुह्यते पयः । गौर्दोग्धव्या पयः । गौर्दुग्धा पयः । गौः सुदोहा पयः । अनेन दुह्यादयः सर्व एवोदाहरणानीति दर्शितम् । तत्र सत्यप्यपायो यदा न विवक्ष्यते निमित्तभावमात्रविवक्षैव तु गोस्तदानेन कर्मता । अपादानादिविशेषविनिर्मुक्तं च विद्यते कारकं यथा नटस्य शृणोतीति । यतश्च पयोर्थी प्रथमं गवि प्रवर्तते ततोन्तरङ्गत्वाद् दुह्यादिषु गुणकर्मणि लादयो भवन्ति । सत्यपि चान्तरङ्गत्वे गवादीनामीप्सिततमत्वाभावोऽन्यार्थत्वात् तत्र क्रियाप्रवृत्तेः । **पयसस्त्व**विवक्षायां गोरेवेप्सिततमत्वम् । यथोक्तमपादानमुत्तराणि गां दोग्धीति । पयोविवक्षायां च प्राधान्येप्यन्तरङ्गत्वाद्गुणे लादयः । उक्तं च—

गुणकर्मणि लादिविधिः पूर्वं गुणकर्मणा भवति योगः ।

मुख्यं कर्म प्रेप्सुर्यस्माद्गव्येव यतते प्राक् ।
तस्माच्छुद्धस्य दुहेर्भवति गवा पूर्वमेव संबन्धः ।
गोदुहिना पयसस्तु प्राक् तस्माल्लादयस्तस्मिन्'

इति । अपादानविवक्षायां तु पञ्चमी भवति—गोर्दुह्यते पय इति । यदा तु पयोविशेषणत्वेन गोर्विवक्षा तदा षष्ठी गोः पयो दोग्धीति । माणवकाय धर्मं ब्रूत इत्यपि भवति यदा धर्मेण कर्मणा माणवकस्याभिप्रेयमाणत्वं लक्ष्यते । तदविवक्षायां त्वनेन कर्मत्वम् ॥ **सपर इति ।** उत्तरसूत्रेप्ययमेव विधिरित्यर्थः । बोध्यते माणवकं धर्मः, श्राव्यते माणवकं श्लोकः, भोज्यते माणवकमोदन इति । प्रयोजकव्यापारेणाप्यमानत्वान्माणवकस्य प्राधान्यं धर्मादेस्तु गुणभावः ॥

(उद्योतः) सर्वोदाहरणवाचाह—भाष्ये—**कथितेऽभिहिते इति ।** प्रधानकर्मणि लादिभिरभिहिते गुणकर्मणि **त्वस्या**न्यस्य पष्ठ्यादेर्विधिरिति **त्वस्यान्यस्य** संसारविलक्षणस्य मतिरित्यर्थः ॥ **चतुर्थीपञ्चम्याविति** चतुर्थ्युक्तिर्भ्रशासाद्यभिप्रायेण ॥ इदमुपलक्षणं व्रजमवरुणद्धीत्यत्र सप्तम्यपीति बोध्यम् ॥ ननु तव विधिरित्यसंगतमत आह—**अस्वपदेनेति ॥** युष्मच्छब्दोप्यहंकारानास्पदचेतनत्वेनान्यमेवाहेत्याह—**युष्मदर्थस्येति ॥** तद् ध्वनयन्वक्ष्यति—भाष्ये—**नैवमन्ये मन्यन्तइति ॥ अनेनेति ।** परसूत्रसहितैतत्सूत्रविषये दुहादौ ॥ **गुणकर्मणी**त्याचार्योक्त्याऽप्रधाने दुहादीनामित्याचार्यान्तरोक्त्या च सर्वेषामेवैतदुदाहरणत्वम् । **अपूर्वविधा**वित्यस्य च पूर्वविधिविषयाभावे तद्विषयाविवक्षायां चेत्यर्थ इति भावः ॥ अत्र गुणकर्मत्वं **प्रधानकर्मभिन्नत्वम् ।** प्रधानकर्मत्वं प्रधानकर्तृनिष्ठव्यापारजन्यफलाश्रयत्वम् ॥ तद्भेदश्चैकव्यापारार्थकदुहादिष्वनेन कर्मत्वे फलाश्रयत्वाभावाद् । ण्यन्ते तु धर्मादेः प्रधानकर्तृव्यापारजन्यफलाश्रयत्वाभावादिति बोध्यम् । ये तूद्देश्यत्वानुद्देश्यत्वरूपे व्यापारद्वयजन्यफलाश्रयत्वतदभावरूपे वा प्राधान्याप्राधान्ये वदन्ति, तेषां दुहादीनां द्व्यर्थतायामपि गवादावीदृशाप्राधान्यसत्त्वेन पयसि च प्राधान्यसत्त्वेन तदादायैवैतदुपपत्तावस्य भाष्यस्य सर्वोदाहरणत्वतात्पर्यानुपपत्तिरेवेति दिक् ॥ **निमित्तभावमात्रविवक्षेति ।** क्रियाजनकत्वमात्रविवक्षेत्यर्थः ॥ परिगणनफलं दर्शयति—**अपादानादिविशेषेति ॥ गुणकर्मणि लादिविधि**रित्यर्थस्य न्यायसिद्धत्वं दर्शयति—**यतश्चेति ॥** नन्वेवं पूर्वेणैव सिद्धं स्यादत आह—**सत्यपि चेति ।** वस्तुत ईप्सिततमत्वसत्त्वेपि न क्षतिः ॥ आकडारसूत्रस्थभाष्योपपत्तिश्च प्रागुक्तैवेति न विस्मर्तव्यम् । किं च विभागजसंयोगानुकूलव्यापारानुकूलव्यापारार्थकत्वं तदुदाहरणे आवश्यकमुभयोः प्राप्तये । तत्र विभागस्य संबन्धिद्वयाकाङ्क्षत्वेन पयसोऽविवक्षेति वक्तुमप्यशक्यम् ॥

प्रसिद्धेरप्रयोग इति त्वन्यत् । किं च व्यापारद्वयार्थत्वे मुख्यगोपालव्यापारजन्यफलाश्रयत्वरूपं गोः प्राधान्यमादाय तत्रैव कर्मणि लादयः । तच्च **प्रधानकर्मण्याख्येये** इत्यादिना वक्ष्यति, ॥ यदा त्वेकव्यापारार्थत्वं दुहादीनां तदाऽनेन कर्मत्वे तादृशप्राधान्यस्य गव्यभावात् तत्र लाधप्राप्तौ **गुणकर्मणि लादय** इत्युक्तम्, गम्यते ग्रामं देवदत्त इत्यादौ देवदत्तस्य मदुक्तमेव प्रधानकर्मत्वमिति दिक् ॥ **अन्तरङ्गत्वादिति** । प्रधानन्यायान्तरङ्गन्याययोः समत्वाद् ॥ **गतिबुद्धी**तिसूत्रस्य नियमत्वपराद्धे**तुमति** चेतिसूत्रस्यभाष्यादन्तरङ्गन्यायात्प्रधानन्यायस्य वलवत्त्वाच्चास्यार्थस्य वाचनिकत्वमेवेत्यपरे ॥ **उक्तंचेति** । हरिणेति शेषः ॥ **पूर्वंगुणकर्मणे**त्यस्य यत इति शेषः । एवं गुणकर्मयोगे हेतुमाह—**मुख्यं कर्मे**ति । **शुद्धस्य दुहेः** पयोनन्वितस्य दुहेः ॥ तदेवाह—**पूर्वमेवेति** । पयःसंबन्धात्पूर्वमेवेत्यर्थः ॥ **गोदुहिना** गवान्वितदुहिना तु यतः प्राक् गवा संबन्धस्तस्मात्तस्मिन् लादय इत्यर्थः ॥ **उत्तरसूत्रे इति** । गतिबुद्धीतिसूत्रे ह्रक्रोरितिसूत्रे चेत्यर्थः ॥ **अयमेव विधिरिति** । अयमेव प्रकार इत्यर्थः ॥ **माणवकस्य प्राधान्यमिति** । एवं च प्रयोज्यव्यापारजन्यफलाश्रयो गुणकर्मेत्यर्थः ॥

(११०५ नियमवार्तिकम् ॥ ६ ॥)

॥ * ॥ ध्रुवचेष्टितयुक्तिषु चाप्यगुणे तदनल्पमतेर्वचनं स्मरत ॥ * ॥

(भाष्यम्) **ध्रुवयुक्तिषु चेष्टितयुक्तिषु चाप्यगुणे कर्मणि लादयो भवन्तीत्येतदनल्पमतेराचार्यस्य वचनं स्मर्यताम् ॥**

(प्रदीपः) **ध्रुवेति** । **अगुणे** प्रधानकर्मणि । **ध्रुवयुक्ति**ष्वकर्मकेषु **चेष्टितयुक्तिषु च** गत्यर्थेषु च लादयो भवन्ति । पूर्वाचार्यप्रसिद्ध्या ध्रुवयुक्तयोऽकर्मका उच्यन्ते । तेषां हि क्रिया स्वात्मन्येवावस्थिता न तु कर्मार्थो । तत्र ध्रुव इव ध्रुव इति स्वात्मनिष्ठोऽकर्मको धात्वर्थ उच्यते । तेन मासमास्यते देवदत्तः शाय्यते क्रोशं देवदत्त इति प्रयोज्ये देवदत्ते प्रयोजकव्यापारस्य तत्रैव पूर्वं संनिपाताल्लादयो भवन्ति । तथा गम्यते ग्रामं देवदत्त इत्यत्रापि ॥ **अनल्पमतेरिति** । मेधाविन आचार्यस्येत्यर्थः ॥ **स्मरतेति** । आगमस्याविच्छेदमनेन दर्शयति ॥

(उद्द्योतः) **स्वात्मन्येव** स्ववानात्मा यस्य तस्मिन्कर्त्तरीत्यर्थः । स्वसमानाधिकरणफलार्थेति यावत् ॥ **न तु कर्मार्थेति** । न कर्मनिष्ठफलार्थेत्यर्थः ॥ **अकर्मको धात्वर्थ इति** । तेन युक्तिः संवन्धो येषामित्यर्थः ॥ एवं **चेष्टितयुक्ति**पदमपि व्याख्येयम् ॥ **तत्रैव पूर्वमिति** । अनेनान्तरङ्गत्वमपि तस्य दर्शितम् । अनया युक्त्या बुद्धिप्रत्यवसानार्थेष्वपि प्रधान एवापत्तिरित्यस्यार्थस्य वाचनिकत्वमेव युक्तम् ॥ **आगमस्य** परम्परोपदेशस्य ॥

(आचार्यान्तरोक्तिभाष्यम्)

अपर आह—

(११०६ नियमवार्तिकम् ॥ ७ ॥)

॥ * ॥ प्रधानकर्मण्याख्येये लादीनाहुर्द्विकर्मणाम् ॥ * ॥

(भाष्यम्) **प्रधानकर्मण्यभिधेये द्विकर्मणां धातूनां कर्मणि लादयो भवन्तीति वक्तव्यम् । अजां नयति ग्रामम् । अजा नीयते ग्रामम् । अजा नीता ग्राममिति ।**

(प्रदीपः) आगम एवायं न स्वमतिपरिकल्पनेति दर्शयितुमाह—**अपर इति** । **अजा नीयत इति** । अजायाः प्राधान्यान्नेतुश्च तस्यामेव पूर्वं क्रियाप्रवर्तनादन्तरङ्गत्वाच्च तस्यामेव लादयः ॥

(उद्द्योतः) प्रधानकर्मणि प्रवृत्तौ युक्तिमाह—**अजाया इति** । ध्रुवचेष्टितयुक्तिष्विति पूर्वश्लोकेपि चेष्टितयुक्तित्वेन नयत्यादीनामपि ग्रहणमिति न तस्य न्यूनता । प्राधान्यं चाजायाः कर्तृव्यापारजन्यफलाश्रयत्वात् ॥ अत्र व्यापारद्वयार्थकतया **कर्तुरीप्सिततम**मित्यनेन येषु द्वयोः कर्मत्वं ते ऽत्र द्विकर्मका उच्यन्ते । न्यादीनां च तेनैव द्विकर्मकतेति वोध्यम् ॥

(११०७ नियमवार्तिकम् ॥ ८ ॥)

॥ * ॥ अप्रधाने दुहादीनाम् ॥ * ॥

(भाष्यम्) **अप्रधाने दुहादीनां 'कर्मणि लादयो भवन्तीति वक्तव्यम्' । दुह्यते गौः पयः ।**

(११०८ नियमवार्तिकम् ॥ ९ ॥)

॥ * ॥ ण्यन्ते कर्तुश्च कर्मणः ॥ * ॥

(भाष्यम्) **ण्यन्ते कर्तुश्च कर्मणः 'लादयो भवन्तीति [वक्तव्यम्]' । गम्यते यज्ञदत्तो ग्रामं देवदत्तेन ।**

(प्रदीपः) **ण्यन्ते कर्तुश्च कर्मण इति** । कर्तुःसतो ण्यन्ते धातौ कर्मणो वाचका लादयो भवन्ति । **गतिबुद्धी**त्यनेन यस्य प्रयोज्यस्य कर्मसंज्ञा विधीयते तस्मिन्वाच्ये सर्वेषु गत्यर्थादिषु धातुषु लादयो भवन्तीत्यर्थः । पूर्वश्लोके तु भेदेनोक्तं गत्यर्थाकर्मकेषु प्रधाने कर्मणि । बुद्धिप्रत्यवसानार्थशब्दकर्मकेषु तु **अपर** इत्यनेन वचनेन लादयो गुणकर्मणि ॥ प्रयोज्यकर्मण्येव लादयो दृश्यन्त इत्येकेषां मतम् ॥ माणवकं धर्मं बोधयतीत्यादावनियतो गुणप्रधानभाव इत्याहुः । धर्मप्रतिपादनपरत्वे वाक्यस्य धर्मस्य प्राधान्यं, माणवकस्य गुणभावः । माणवकसंस्कारपरायां तु प्रवृत्तौ माणवकस्य प्राधान्यं धर्मस्य गुणभावः । तथाऽभिधानव्यापारेण प्रयोजकव्यापारस्य प्राधान्यात्प्रयोज्यस्यैव कर्मणः प्राधान्यम् । गुणभूतप्रयोज्य-

व्यापारकर्मणस्तु गुणभावः। आर्थेन तु न्यायेन प्रयोज्यव्यापारस्य प्राधान्यम्। तदर्थत्वात्प्रयोजकव्यापारस्य तत्प्राधान्यात्तत्कर्मणोपि प्राधान्यमिति वदन्त आचार्याः॥

(उद्द्योतः) भाष्ये—ण्यन्ते कर्तुश्चेति। यद्यपि प्रधानकर्मणीत्यनेनैवेदं सिद्धं तथापि गुणकर्मणि लादिविधिः सपरे इत्युक्तेर्दुह्यादीनामित्यनेन तस्य ग्रहणमिति भ्रमवारणार्थं पुनरिदमुक्तं तच्च सामान्योक्तेर्बुद्ध्यादिविषयमपि। तद्ध्वनयन्नाह—पूर्वश्लोके त्विति। प्रधाने कर्मणि प्रयोज्यरूपे कर्मणि गुणकर्मणि प्रयोज्यनिष्ठव्यापारजन्यफलाश्रये॥ प्रयोज्यकर्मण्येवेति। बुद्धिप्रत्यवसानार्थादिष्वपीत्यादिः॥ एकेषां मतमिति। एवं च बुद्धिप्रत्यवसानार्थशब्दकर्मकेषु विकल्पः फलित इति भावः॥ तत्र विकल्पे युक्तिमाह—माणवकमित्यादिना। वस्तुत इदं सर्वं वाचनिकमिति तत्त्वम्॥ अभिधानव्यापारेणेति। शब्देनेत्यर्थः। एतच्च द्वैविध्यं गत्यर्थण्यन्तव्यतिरिक्तविषयमिति नातिप्रसङ्गः॥ इदमत्रावधेयम्—अकर्मकव्यतिरिक्तहृक्रप्रकृतिकण्यन्तयोर्हारयतिकारयत्योर्द्विकर्मकत्वे पूर्वमते गौणे प्राप्नोति। अपर आहेति मते प्रधाने प्राप्नोतीत्यत्रापि विकल्प एवेत्येके॥ अन्ये तु भुवचेष्टितयुक्तिषु चापीत्यत्र चकारेण चेष्टितयुक्तिपदेन हृक्रोर्ग्रहणेन वा तयोरपि प्रयोज्यकर्मण्येवेत्याहुः॥ अत्र निश्चयो बहुद्रष्टृभिः कार्यः॥

(द्विकर्मकधातुनिर्णयाधिकरणम्)

(अनुयोगभाष्यम्)

के पुनर्धातूनां द्विकर्मकाः?।

(प्रदीपः) दुह्यादिपरिगणनादन्यत्र द्विकर्मकत्वं न प्राप्नोति दृश्यते चेति मत्वा पृच्छति—के पुनरिति॥

(उद्द्योतः) ननु दुह्यादिव्यतिरिक्ता द्विकर्मका अप्रसिद्धा इति प्रधानकर्मणीत्याद्यसंगतमित्याशयेन पृच्छति—के पुनरिति॥

(समाधानभाष्यम्)

नीवह्योर्हरतेश्चापि गत्यर्थानां तथैव च।
द्विकर्मकेषु ग्रहणं द्रष्टव्यमिति निश्चयः॥ १॥

अजां नयति ग्रामम्, भारं वहति ग्रामम्, भारं हरति ग्रामम्॥ गत्यर्थानाम्—गमयति देवदत्तं ग्रामम्, यापयति देवदत्तं ग्रामम्॥

(प्रदीपः) गत्यर्थानामिति। उत्तरसूत्रोपात्तधातूपलक्षणं गत्यर्थग्रहणम्॥ तथैव चेति। चकारेण जयत्यादयः समुच्चीयन्ते इत्याहुः॥ शतं जयति देवदत्तम्। शतं मुष्णाति देवदत्तम्। शतं दण्डयति देवदत्तम्॥

(उद्द्योतः) नीत्यादि। इदं व्यापारद्वयार्थकधातूपलक्षणम्। एषां च कर्तुरीप्सिततममिति द्विकर्मकत्वम्, न त्वेषां दुह्यादिषु पाठे मानमस्ति। एवं च जिदण्ड्यादीनामपि सिद्धं द्विकर्मकत्वम्। अत्र प्रधानव्यापारजन्यफलाश्रयत्वरूपप्रधानकर्मत्वाद्देवदत्तादौ लादिः। उद्देश्यत्वलक्षणं प्राधान्यं तु शतस्येति अनुद्देश्यगर्गानुरोधाद् नोद्देश्यशनाद्स्विति न वृद्धिमूत्रस्थभाष्यविरोध इत्याहुः॥

(११०९ द्विकर्मकत्वबाधकवार्तिकम्॥ १०॥)

॥ * ॥ सिद्धं वाप्यन्यकर्मणः ॥ * ॥

(भाष्यम्) **सिद्धं वा पुनरेतद्भवति॥ कुतः?। अन्यकर्मणः। अन्यस्याजा कर्म, अन्यस्य ग्रामः। अजामसौ गृहीत्वा ग्रामं नयति।**

(प्रदीपः) सिद्धं वेति। अन्यस्याश्रूयमाणस्य क्रियाविशेषस्य कर्मणः संभवादित्यर्थः। अथ वा कर्मशब्देन कर्मत्वमुच्यते। अन्यकर्मत्वादित्यर्थः। विभाषा गुण इति पञ्चमी। यथा प्रविश पिण्डीमिति भक्षणापेक्षं पिण्ड्याः कर्मत्वम्, तथाऽजां ग्रामं नयतीत्यत्र ग्रहणापेक्षमजायाः कर्मत्वम्। नयतिस्तु प्राप्तिमात्रवाची। तेनाजां गृहीत्वा ग्रामं प्राप्नोतीति वाक्यार्थः संपद्यते॥

(उद्द्योतः) भाष्ये—ऽन्यस्येति। अश्रूयमाणस्य ग्रहणादेरित्यर्थः। व्यधिकरणे षष्ठ्यौ॥

(१११० द्विकर्मकत्वसाधकवार्तिकम्॥ ११॥)

॥ * ॥ अन्यकर्मेति चेद् ब्रूयाल्लादीनामविधिर्भवेत्॥ * ॥

(भाष्यम्) **अन्यकर्मेति चेद् ब्रूयाल्लादीनामविधिरयं भवेत्। अजा नीयते ग्राममिति। परसाधन उत्पद्यमानेन लेनाजाया अभिधानं न प्राप्नोति॥**

(प्रदीपः) परसाधन इति। नीयते इति नयतेः परेण लकारेण नयतिकर्मैवाभिधानीयम्। ग्रहणस्य त्वजा कर्म, न नयतेरिति कथं सा लेनाभिधीयते तस्मादन्यकर्मत्वमजाया नैष्टव्यम्॥

(उद्द्योतः) परसाधने इति। नयति साधने ग्रामादावित्यर्थः। तदयं निष्कर्षः—

"गौणे कर्मणि दुह्यादेः प्रधाने नीहृकृष्वहाम्।
बुद्धिभक्षार्थयोः शब्दकर्मणां च निजेच्छया।
प्रयोज्यकर्मण्यन्येषां ण्यन्तानां लादयो मताः।
हृक्रोर्निजेच्छया किं वा प्रयोज्ये बहुदर्शिभिः।
लक्ष्यं दृष्ट्वा निर्णयोत्र कर्त्तव्यो भाष्यपारगैः"रिति॥

(न्यूनतापूरकाधिकरणम्)

(११११ न्यूनतापूरकवार्तिकम्॥ १२॥)

॥ * ॥ कालभावाध्वगन्तव्याः कर्मसंज्ञा ह्यकर्मणाम्॥ * ॥

(भाष्यम्) **कालभावाध्वगन्तव्या अकर्मकाणां धातूनां कर्मसंज्ञा भवन्तीति वक्तव्यम्॥ काल—मासमास्ते। मासं स्वपिति॥ भाव—गोदोहमास्ते। गोदोहं स्वपिति॥ अध्वगन्तव्य—क्रोशमास्ते। क्रोशं स्वपिति॥**

(प्रदीपः) कालेति। मासादय एव कालवाचित्वेन लोके प्रसिद्धाः न तु गोदोहनपानादय इति सत्यपि भावस्य कालत्वे पृथगुपादानं कृतम् ॥ निर्ज्ञातपरिमाणा हि क्रिया अनिर्ज्ञातपरिमाणायाः क्रियायाः परिच्छेदायोपादीयमाना मास-गोदोहादिशब्दवाच्या काल इति दर्शनम् ॥ अध्वा चासौ गन्तव्योऽध्वगन्तव्यः। अत एव निपातनाद् विशेषणस्यापि परनिपातः। गन्तव्यतया लोके यः प्रसिद्धः क्रोशयोजनादि—नियतपरिमाणः तस्यैव कर्मत्वं नान्यस्येत्यध्वानं स्वपितीति न भवति ॥ केचिदध्वगत्यन्ता इति पठन्ति। तत्रायमर्थः—गतेरन्तो निष्ठा निश्चयो वा येषु ते गत्यन्ताः क्रोशयोजनादयः। अध्वनो गत्यन्ता इति षष्ठीसमासः ॥ **कर्मसंज्ञा हीति।** ननु **कालाध्वनो**रिति द्वितीया सिद्धेति किं कर्मसंज्ञया। गोदोहादीनां कालत्वेनाप्रसिद्धत्वाद् द्वितीया न प्राप्नोतीति भावस्य तावत्कर्मसंज्ञा विधेया। कालाध्वनोरपि लादिविधानार्थं कर्मत्वमेषितव्यम्। आस्यते मासः। आसितव्यो मासः। आसितो मासः। स्वासो मासः। एवं शय्यते क्रोश इत्यादि द्रष्टव्यम् ॥ यदा त्वङ्गीकृतसकर्मकधात्वन्तरार्थे आसनादावासादयो वर्तन्ते तदा पूर्वेणैव कर्मत्वं सिद्धम्। तथाहि—मासमास्त इत्यस्यायमर्थः। मासमासनेन व्याप्नोतीति। तथा च वक्ष्यति—**प्राकृतमेवेदं कर्म यथा कटं करोतीति।** अत्र दर्शने न केवलमकर्मकाणां कालादयः कर्मत्वं प्रतिपद्यन्ते अपि तु सकर्मकाणामपि। न्यायस्य तुल्यत्वात् ॥

(उद्द्योतः) नन्वकर्मकाणां व्यर्थकर्मसत्त्वेपि द्विकर्मकत्वाभावाद् **ध्रुवयुक्तिष्वगुण** इत्यसंगतमतो भाष्ये **कालेति** ॥ ननु गोदोहादीनामपि कालत्वादेव सिद्धिरत आह—**मासादय एवेति।** गोदोहमास्ते इत्यस्य यावन्तं कालं गौर्दुह्यते तावदास्ते इत्यर्थः ॥ **पानादय इति।** गवामित्यादिः। गोपानमास्त इत्यस्य यावत्कालं गावो जलं पिबन्ति तावदास्ते इत्यर्थः ॥ क्वचित्पाकादय इति पाठः ॥ **निर्ज्ञातपरिमाणेति।** इदं **कालाः परिमाणिने**तिसूत्रस्थभाष्यविरुद्धम् ॥ **लादिविधानार्थमिति।** अनत्यन्तसंयोगे द्वितीयार्थमित्यपि बोध्यम्। द्वितीयाविधानमपि मासं गुडधाना इत्यादावक्रियायोगे चरितार्थम् ॥ इदमपूर्वकर्मसंज्ञाविधायकमिति मत्वाह—**यदात्विति ॥ पूर्वेणैव कर्तुरीप्सिततमं कर्मे**त्यनेन ॥ **वक्ष्यतीति। कालाध्वनो**रिति सूत्रे इति शेषः। **यथा कट**मिति दृष्टान्तेन **कर्तु**रित्येव तत्र प्राकृतशब्देन विवक्षितमिति भावः ॥ अस्य प्रकारस्यावश्यकत्वमित्याह—**सकर्मकाणामपीति।** न चेयमपि कल्पनाऽकर्मकविषयैव न सकर्मकविषयेति वाच्यम्। अनया रीत्या सकर्मकाकर्मकसाधारणकालाध्वनोरित्येतद्विषयस्य **न तर्हीदानीमिदं वाच्य**मिति-प्रश्नस्य **यत्राक्रियया**ऽत्यन्तसंयोगस्तदर्थमित्युत्तरस्य च **कालाध्वनो**रितिसूत्रभाष्यस्यासंगत्यापत्तेः। दृश्यते च मासमधीते इत्यादौ कालस्य कर्मत्वम्। अनया रीत्या ऽकर्मकधातुयोगे कटादीनां कर्मत्वं तु नापाद्यमनभिधानादित्याहुः ॥ वस्तुतोऽनयैव कल्पनयैषां सकर्मकत्वम्, न त्वत्रत्यमिदं वचनं विधायकं हिशब्दयोगात्। व्याख्यानभाष्यस्यापि कालादयोऽकर्मकधातूनां कर्मसंज्ञा यथा भवन्ति तथा धात्वर्थरूपं वक्तव्यमुक्तयुक्तेरिति **ध्रुवयुक्तिष्वगुण** इति सम्यगेवेत्यर्थ इति युक्तमाभाति। अन्यथा वचनस्य यदा त्वित्यादिनोक्तया **कालाध्वनो**रितिसूत्रभाष्यसंमतया रीत्या प्रत्याख्याने आरम्भप्रत्याख्यानयोः फलभेदापत्तिः। आरम्भेपि तदावश्यकत्वेनानारम्भपरतयैवैतद्ग्रन्थव्याख्याया न्याय्यत्वात् ॥

(१११२ न्यूनतापूरकवार्तिकम् ॥ १३ ॥)

[॥ * ॥ देशश्च ॥ * ॥]

(भाष्यम्) **देशश्चाकर्मकाणां कर्मसंज्ञो भवतीति वक्तव्यम्। कुरून्स्वपिति। पञ्चालान्स्वपिति ॥**

(प्रदीपः) **देशश्चेति।** संख्यायविशेषः कुरुपञ्चालादिदेश इह गृह्यत इति भाष्य उदाहरणाद्विज्ञायते ॥

(उद्द्योतः) संख्यायविशेषः ग्रामादीनां समूहविशेषः ॥

(पूर्वाचार्यकृतसंज्ञानिराकरणाधिकरणम्)

(कल्मसंज्ञाभाष्यम्)

विपरीतं तु यत्कर्म तत्कल्म कवयो विदुः।

किमिदं कल्मेति?। अपरिसमाप्तं कर्म कल्म। न वा अस्मिन्सर्वाणि कर्मकार्याणि क्रियन्ते ॥ किं तर्हि? ॥ द्वितीयैव ॥

(प्रदीपः) इदानीमकथितस्य पूर्वाचार्यकृतं संज्ञान्तरं दूषयितुमुपन्यस्यति—**विपरीतमिति।** कर्मधर्माणां विपर्यस्तत्वाद्विपरीतमुच्यते। ईप्सिततमं द्वेष्यमितरच्चेति पूर्वं त्रिविधं कर्म निर्दिष्टमिदं तद्विपरीतम्। कपिलकादित्वाच्च लत्वे कल्मेति भवति ॥ **अपरिसमाप्तमिति।** ईप्साप्रकर्षाभावादित्यर्थः ॥ **नवेति।** लकृत्यक्तखलर्थानामविधानात् **प्रधानकर्मण्यभिधेय** इति पूर्वमुक्तत्वात् ॥ दुहादीनां त्वप्रधानकर्मणि लादिविधानात्तुच्छ एवायं पक्षः। तथा च परस्ताद्दूषयिष्यते ॥

(उद्द्योतः) **इतरदिति।** उदासीनमित्यर्थः ॥ **इदं तद्विपरीतमिति।** धात्वर्थफलाश्रयत्वाभावादिति भावः ॥ श्लोकस्थविपरीतशब्दं व्याचष्टे—भाष्ये **अपरिसमाप्तमिति।** अपरिसमाप्तत्वं व्याचष्टे—**नवेति ॥ कल्मकर्मणोर्द्वितीये**ति कार्यम्। अत्र पक्षे ईप्साप्रकर्षाभावादपरिसमाप्तत्वं तु न युक्तमुदासीनेपि तथात्वापत्तेः। भाष्येन्यस्यैवोक्तेश्च ॥ सर्वकर्मकार्याभावे हेतुमाह—**प्रधानकर्मणीति।** कथिते लादय इति येनोक्तं स एवायं वादीति भावः ॥ तदेतत्स्वयं दूषयति—**दुहादीनां चे**त्यादिना।

(विपरीतकर्मलक्षणभाष्यम्)

यस्मिंस्तु कर्मण्युपजायतेऽन्यद्धात्वर्थयोगापि च यत्र षष्ठी।

तत्कर्म कल्मेति च।

(प्रदीपः) तस्यैव विपरीतकर्मणो लक्षणं दर्शयति—**यस्मिंस्त्विति**। यस्मिन् गवादौ कर्मणि सत्यन्यत्पयःप्रभृत्युपजायते तत्कर्म कल्म ॥ **धात्वर्थयोगेति** । धातुशब्देन धात्वर्थ उच्यते । तस्यार्थः प्रयोजनं पयःप्रभृति तेन योगो यस्याः सा षष्ठी यत्र भवति गोर्दुह्यते पयः पौरवस्य कम्बलो याच्यत इति। प्रधाने तु न भवति षष्ठी दुह्यते पयसो गौरिति॥

(उद्द्योतः) **अन्यत्पयःप्रभृतीति** । ननु पौरवं विनापि गोरुपजननात्तत्राव्याप्तमिदं याचादिकर्मत्वविशिष्टस्य तत्सत्त्वे एवोपजननेनादोषात्। एवं चोपजायत इत्यस्य प्रकृतधात्वर्थकर्मताविशिष्टमित्यर्थः ॥ **तेन योग इति** । तेन योगो वाच्यो यस्याः सा षष्ठीत्यर्थः । धात्वर्थव्यापारप्रयोजनफलविशिष्टपयआदिनिरूपितसंबन्धार्थिका यत्र षष्ठीत्यर्थः । एवं च दुहादियोगे पयसो गव्यन्वयं कृत्वा षष्ठीप्रयोगो न दृश्यते किं तु गोः पयस्यन्वये सा दृश्यते इति भावः ॥

(कल्मलक्षणानावश्यकताभाष्यम्)

कल्म नोक्तं धातोर्हि वृत्तिर्न रलत्वतोस्ति ॥

(प्रदीपः) इदानीं संज्ञान्तरमनारभमाण आह—**कल्मनोक्तमिति**। यस्मात्तत्कर्मैव तस्मात् पृथक्कल्मेति नोक्तमस्मिन् शास्त्रे दुहादीनामप्रधाने कर्मणि लादिदर्शनात् सर्वकर्मकार्योपपत्त्याऽपरिसमाप्तत्वाभावाद् भेदेन च कल्मसंज्ञाविधाने कर्मकार्याप्रसङ्गादिति भावः॥ **धातोर्हि वृत्तिरिति**। रेफस्य लत्वमात्रेण धातोरर्थान्तरे वृत्तिर्नास्तीत्यर्थः ॥ क्वचित्तु पाठः **धातोर्निवृत्तिरिति**। तत्रायमर्थः—धातोः करोते रेफस्य लत्वमात्रेण स्वार्थान्निवृत्तिर्नास्तीति । एतदुक्तं भवति—वर्णविकारेपि कृते कर्मकल्मशब्दयोः पर्यायतैव । यथा पांसुरपांसुलशब्दयोः तत्र किं संज्ञाभेदेनेत्यर्थः ॥

(उद्द्योतः) **कर्मकार्येति**। द्वितीयादीत्यर्थः ॥ **रलत्वत इति**। सार्वविभक्तिकस्तसिः। रस्य लत्वमात्रेणेत्यर्थः ॥

(आक्षेपभाष्यम्)

एतेन कर्मसंज्ञा सर्वा सिद्धा भवत्यकथितेन ।
तत्रेप्सितस्य किं स्यात् प्रयोजनं कर्मसंज्ञायाः ॥

(प्रदीपः) **एतेनेति**। **अकथितं** कर्मेत्येवास्तु माभूत्पूर्वसूत्रद्वयम्। तद्विषयेऽनेनैव कर्मसंज्ञायाः सिद्धत्वात्। परिगणनं च न करिष्यत इति प्रश्नार्थः ॥

(उद्द्योतः) ननु परिगणनस्य सत्त्वात्सर्वत्र न सिध्यतीत्यत आह—**अकथितमित्यादि**। एवं **चाकथितेन** 'अकथितं चेति सूत्रेणैव **सर्वा** सर्वविषया कर्मसंज्ञा **सिद्धा** किं पूर्वसूत्रद्वयेनेति श्लोकार्थः। अनेन सूत्रत्रयविहितसंज्ञासंज्ञिनी शक्तिरेकैवेति सूचयति। आद्यसूत्रद्वये फलाश्रयताजनकतोभयसमानाधिकरणा, इह तु जनकतामात्रसमानाधिकरणेत्यन्यत् ॥

(समाधानभाष्यम्)

यत्तु कथितं पुरस्तादीप्सितयुक्तं च तस्य सिद्ध्यर्थम्। ईप्सितमेव तु यत्स्यात्तस्य भविष्यत्यकथितेन ॥

(प्रदीपः) **यत्त्विति**। यवेभ्यो गा वारयतीति गवां कथितत्वात्कर्मसंज्ञा न स्याद् **वारणार्थाना**मित्यपादानसंज्ञैव तु स्यादिति **कर्तुरीप्सिततम**मित्यारब्धम्। तस्मिन्नारब्धे अनीप्सितस्य कर्मसंज्ञा न प्राप्नोतीति **तथायुक्त**मित्यारब्धव्यम् ॥ ननु तथायुक्तस्यानेन भविष्यति। नैतदस्ति। दुह्यादिपरिगणनं नटस्य शृणोतीत्यादावतिप्रसङ्गनिवृत्त्यर्थमवश्यं वक्तव्यम् ॥ **ईप्सितयुक्तं चेति**। ईप्सितेन यवादिना युक्तं यद्गवादि वार्यमाणं तस्य कर्मसंज्ञासिद्ध्यर्थं पूर्वसूत्रं कर्तव्यमित्यर्थः। चशब्दात्कर्मापादानसंज्ञयोर्विषयविभागसिद्ध्यर्थं चेत्युक्तं **भवति** ॥ **ईप्सितमेवेति** । अवधारणेनेप्साप्रकर्षाभावं दर्शयति ॥ **अकथितेनेति** । सूत्रैकदेशानुकरणमेतत् । **अनेन सूत्रेणे**त्यर्थः ॥

(उद्द्योतः) उत्तरमाह—**यत्त्विति**। **यत्पुरस्ताद्वारणार्थाना**मिति सूत्रेण कीर्तितं **यदीप्सितेन** यवादिना युक्तं गवादि तस्य संज्ञार्थमाद्यं सूत्रमावश्यकमित्यर्थः। तद्व्याचष्टे—**यवेभ्य इत्यादिना** ॥ **अवश्यं कर्तव्यमिति**। सति परिगणने ओदनं पचतीत्याद्यसिद्धेः पूर्वयोगारम्भ आवश्यकः। परिगणनत्वं चास्याख्**यातोपयोग** इति सूत्रे भाष्ये उक्तम् ॥ ननु **वारणार्थानामीप्सित** इत्यनेनेप्सितस्यापादानत्वेपीप्सिततमस्याकथितत्वात्सिध्यत्येवानेन कर्मत्वमित्यतो भाष्ये **चेति**। तद्व्याचष्टे—**चशब्दादिति** । **विषयविभागेति**। विशेषेति पाठान्तरम् ॥ ईप्सितमपादानत्वविषय ईप्सिततमं कर्मत्वस्य विपरीतं वेत्यत्र विनिगमकाभावादिति भावस्तदेवाह—**भाष्ये ईप्सितमेव त्वित्यादिना** । विनिगमनाविरहेणेप्सितस्यैव कर्मत्वमीप्सिततमस्यैवापादानत्वं स्यादिति भावस्तदेवाह—**अवधारणेनेति**। एतेनैतद्भाष्यबलेनाकथितं चेति सूत्रे ईप्सिततममित्यनुवर्त्यं फलाश्रयस्यैवानेन कर्मसंज्ञां वदन्तः परास्ताः ॥

(आक्षेपभाष्यम्)

अथेह कथं भवितव्यम्—नेताश्वस्य स्रुघ्नम् इति। आहोस्वित्-नेताश्वस्य स्रुघ्नस्येति ॥

(प्रदीपः) **अथेहेति**। **प्रधाने कर्मण्यभिधेये लादीनाहुरि**त्युक्तम्। तत्र लादिग्रहणेन किं षष्ठ्यपि गृह्यते उत न। यद्यादिशब्दो व्यवस्थायां तदा **लः कर्मणि च भावे चाकर्मकेभ्यस्तयोरेव कृत्यक्तखलर्था** इत्येतेषां ग्रहणं न्याय्यम्। अथ प्रकारे तदा षष्ठ्यपि लादिग्रहणेन गृह्यते इति प्रधानकर्मण्येव सा भवतीति मत्वा प्रश्नः ॥

(उद्द्योतः) ननु लकृत्यक्तखलर्थवत् षष्ठ्यपि भविष्यतीत्यत आह—**प्रधाने इत्यादि** ॥

(समाधानभाष्यम्)

उभयथा गोणिकापुत्रः ॥ अकथितं च ॥ ५१ ॥

(प्रदीपः) **उभयथेति** । गुणकर्मणि षष्ठीद्वितीयादर्शनादुभयमपि स्मर्यते । वाचनिकं चेदं न तु न्याय्यम् । यत्र ह्येकेनैव शब्देन भिन्नकक्ष्ययोर्गुणप्रधानयोः कर्मणोरभिधानं न संभवति तत्र प्रधानकर्मण एवाभिधानं न्याय्यम् । षष्ठी तु पृथग्गुणप्रधानाभ्यां द्वितीयावद्विधीयते विरोधाभावादुभाभ्यां प्राप्ता शिष्टस्मरणाद्गुणकर्मणि विकल्प्यते ॥ ५१ ॥

(उद्द्योतः) ननु षष्ठीवत्तदभावस्य न्यायेनाप्राप्तेरुभयथेत्ययुक्तमत आह—**गुणकर्मणीति** ॥ ननु लादिवत् षष्ठ्यपि प्रधानकर्मण्येव न्याय्येत्यत आह—**यत्र हीति** ॥ **गोणिकापुत्रो** भाष्यकार इत्याहुः ॥ ५१ ॥

(१९२ कर्मसंज्ञासूत्रम् । १ । ४ । ३ आ. १७ ग.)

२९२ गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ ॥ ५२ ॥

(शब्दकर्मशब्दार्थनिर्णयाधिकरणम्)

(आक्षेपभाष्यम्)

शब्दकर्मेति कथमिदं विज्ञायते—शब्दो येषां क्रियेति, आहोस्विच्छब्दो येषां कर्मेति ? ॥

(प्रदीपः) **गतिबुद्धि** ॥ ५२ ॥ **कथमिति** । कर्मशब्देन क्वचित् क्रिया गृह्यते यथा—कर्तरि कर्मव्यतिहार इति । क्वचित्तु साधनं कर्म यथा—वेः शब्दकर्मण इति । ततश्चोभयथा व्यवहारदर्शनात् संशयानः पृच्छति ॥

(उद्द्योतः) **गतिबुद्धि** ॥ ५२ ॥ ननु कृत्रिमत्वात् कर्मकारकस्यैव ग्रहणमुचितमत आह—**कर्मशब्देनेति** ॥

(प्रत्याक्षेपभाष्यम)

कश्चात्र विशेषः ? ॥

(१११३ प्रथमपक्षे आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ शब्दकर्मनिर्देशे शब्दक्रियाणामिति चेद् ह्वयत्यादीनां प्रतिषेधः ॥ * ॥

(भाष्यम्) **शब्दकर्मनिर्देशे शब्दक्रियाणामिति चेद् ह्वयत्यादीनां प्रतिषेधो वक्तव्यः ॥ के पुनर्ह्वयत्यादयः ?। ह्वयति क्रन्दति शब्दायते ॥ ह्वयति देवदत्तः 'ह्वाययति देवदत्तेन' ॥ क्रन्दति देवदत्तः 'क्रन्दयति देवदत्तेन' ॥ शब्दायते देवदत्तः 'शब्दाययति देवदत्तेन' ॥**

(प्रदीपः) **ह्वयत्यादीनामिति** । ह्वयत्यादयो धातवः साध्यमानावस्थं क्रियारूपं शब्दमभिदधतीति शब्दकर्मत्वादतिप्रसङ्गे सति प्रतिषेधो विधेयः ॥ **ह्वयति देवदत्त इति** । पुत्रादेः कर्मणो भावादकर्मकत्वं ह्वयतेर्नाशङ्कनीयम् ॥ **शब्दायते इति** । शब्दं करोतीति शब्दवैरेति क्यङ् । शब्दलक्षणस्यात्र कर्मणोन्तर्भावात् कर्मान्तरायोगाच्चाकर्मकत्वादपि कर्मसंज्ञाप्रसङ्गः ॥

(उद्द्योतः) ननु शब्दस्य गुणत्वात् क्रियात्वं कथमत आह—**ह्वयत्यादय इति** ॥ **कर्मणो भावादिति** । कर्मणः सत्त्वादित्यर्थः ॥ **अकर्मकत्वादपीति** । यो जातः कर्मसंज्ञाप्रसङ्गस्तस्याप्ययं निषेध इत्यर्थः ॥ अत्र वदन्ति—ह्वेञ् स्पर्धायां शब्दे चेत्यभियुक्तैः शब्दशब्देन ह्वेञ्धात्वर्थनिर्देशात्तदर्थकशब्दशब्दात् क्यङि ह्वयतेरिवास्येव पुत्रादिकर्मयोग इति शब्दक्रियाणामिति चेद् ह्वयत्यादीनां प्रतिषेध इति भाष्यसामञ्जस्यान्न्यायाद्दशब्दायतेरकर्मकत्वप्रयुक्तप्राप्तेर्निषेधे मानाभावे चिन्त्योयं कैयट इति ॥

(१११४ आक्षेपान्तरवार्तिकम् ॥ २ ॥)

॥ * ॥ शृणोत्यादीनामुपसंख्यानमशब्दक्रियत्वात् ॥ * ॥

(भाष्यम्) **शृणोत्यादीनां चोपसंख्यानं कर्तव्यम्। के पुनः शृणोत्यादयः ?। शृणोति विजानात्युपलभते। शृणोति देवदत्तः 'श्रावयति देवदत्तम्' । विजानाति देवदत्तः 'विज्ञापयति देवदत्तम्' । उपलभते देवदत्तः 'उपलम्भयति देवदत्तम्' । किं पुनः कारणं न सिद्ध्यति ? । अशब्दक्रियत्वात् ॥**

(प्रदीपः) **शृणोत्यादीनामिति** । शब्दोपलब्धिरूपेर्थे वर्तमानाः शृणोत्यादयः शब्दक्रिया न भवन्ति, शब्दसाधनकर्माणस्तु तद्विषयत्वेन प्रयोगात् । न चैषां बुद्ध्यर्थत्वम् । शृणोत्यादयो हि न ज्ञानमात्रवचनाः । बुद्ध्यर्थौ तु जानात्युपलभत इत्येतौ यद्युपलब्धिमात्रवचनौ तथापि प्रयोजकव्यापारविवक्षायां प्रकरणादिवशाद्यदा शब्दविषयामेवोपलब्धिं प्रत्याययतस्तदा साधनकर्मग्रहणे सिद्ध्यति, न तु क्रियाग्रहण इत्युपसंख्यानं कर्तव्यम् । एवं तु बुद्ध्यर्थत्वादनयोः सिद्ध्यतीति चिन्त्यमेतत् ॥

(उद्द्योतः) **न ज्ञानमात्रेति** । ज्ञानसामान्यवचना एव बुद्ध्यर्थास्तत्र गृह्यन्ते, न तु तद्विशेषवचना इति भावः ॥ **शब्दविषयामेवेति** । श्रोत्रेन्द्रियजज्ञानरूपामित्यर्थः । एवं च ज्ञानविशेषार्थत्वेन न बुद्ध्यर्थत्वात्सिद्धिरिति भावः ॥ **बुद्ध्यर्थत्वादिति** । ज्ञान-

सामान्यार्थत्वमाश्रित्य बुद्ध्यर्थत्वादपि सिध्यतीत्यभिमानः ॥ चिन्त्यमेतदिति । चिन्ताबीजं तु—यदा जानात्यादीनां शब्दविषये श्रावणज्ञाने वृत्तिस्तदाण्यणौ कर्तुर्णौ कर्मत्वमिष्टम् । न च तदा बुद्ध्यर्थत्वेन सिद्धिर्ज्ञानसामान्यार्थत्वाभावात् ॥ एवमेव दृशेरुपसंख्यानम् । अत एव यदा रूपादिविषयकचाक्षुषज्ञाने वृत्तिस्तदा न भवति । यथा विजानाति रूपतर्कः कार्षापणं विज्ञापयति रूपतर्केणेति भाष्याशय इति ॥

(द्वितीयपक्षाभ्युपगमभाष्यम्)

अस्तु तर्हि—शब्दो येषां कर्मेति ॥

(१११५ द्वितीयपक्ष आक्षेपवार्तिकम् ॥ ३ ॥)

॥ * ॥ शब्दकर्मण इति चेज्जल्पतिप्रभृतीनामुपसंख्यानम् ॥ * ॥

(भाष्यम्) **शब्दकर्मण इति चेज्जल्पतिप्रभृतीनामुपसंख्यानं कर्तव्यम् ॥ के पुनर्जल्पतिप्रभृतयः? । जल्पति विलपति आभाषते ॥ जल्पति देवदत्तः 'जल्पयति देवदत्तम्' ॥ विलपति देवदत्तः 'विलापयति देवदत्तम्' ॥ आभाषते देवदत्तः 'आभाषयति देवदत्तम्' ॥**

(प्रदीपः) **जल्पतिप्रभृतीनामिति ।** जल्पत्यादयः शब्दनक्रियायां वर्तन्त इति क्रियाग्रहणे सिध्यति न तु साधनकर्मग्रहणे । पुत्रं जल्पतीत्यादौ शब्दकर्मत्वाभावात् ॥

(उद्द्योतः) **पुत्रं जल्पतीति ।** लालनपूर्वके जल्पने जल्पेर्वृत्तेरिति भावः ॥ एतेनाकर्मत्वात्सिद्धिरित्यप्यपास्तम् ॥

(न्यूनतापूरणाधिकरणम्)

(१११६ आक्षेपवार्तिकम् ॥ ४ ॥)

॥ * ॥ दृशेः सर्वत्र ॥ * ॥

(भाष्यम्) **दृशेः सर्वत्रोपसंख्यानं कर्तव्यम् । पश्यति रूपतर्कः कार्षापणम् 'दर्शयति रूपतर्कं कार्षापणम्' ॥**

(प्रदीपः) **दृशेः सर्वत्रेति ।** यदि क्रियाग्रहणमथ साधनग्रहणमथोभयगत्याश्रयणं सर्वत्र दृशेर्न प्राप्नोतीति भावः ॥ **पश्यति रूपतर्क इति ।** चक्षुःप्रणिधानद्वारक उपलम्भे यदा दृशिर्वर्तते तदैतद्वक्तव्यम् । अन्यत्र तु बुद्ध्यर्थत्वात् सिध्यति ॥ तत्र साधनकर्मग्रहणमित्येष पक्ष आश्रीयते । क्रियाग्रहणे कर्मग्रहणानर्थक्यप्रसङ्गात् । गतिबुद्धिशब्दप्रत्यवसानार्थाकर्मकाणामित्येव सिद्धत्वात् । पुत्रादिकर्मत्वे जल्पतिप्रभृतीनामुपसंख्यानं कर्तव्यमेव । श्लोकादिशब्दविशेषकर्मकत्वे तु शब्दकर्मत्वात्सिद्धिः । दृशेर्बुद्ध्यर्थत्वादेव ग्रहणं सिध्यति ॥

(उद्द्योतः) **सर्वत्र दृशेरिति ।** ज्ञानसामान्यार्थकत्वाभावादिति भावः ॥ ननु **पश्यार्थैश्चानालोचन** इति दर्शनाद् दृशेर्ज्ञानसामान्यार्थकत्वाद् बुद्ध्यर्थत्वेन सिद्धिरत आह—**चक्षुरिति ॥ दृशेरिति ।** ज्ञानसामान्यार्थत्वे इति शेषः । चाक्षुषज्ञानार्थकार्थे तु वचनमावश्यकमेवेति बोध्यम् । इदमेव ज्ञापयति ज्ञानसामान्यार्थकानां तत्र ग्रहणमिति ॥

(प्रतिषेधाधिकरणम्)

(१११७ आक्षेपवार्तिकम् ॥ ५ ॥)

॥*॥ अदिखादिनीवहीनां प्रतिषेधः ॥*॥

(भाष्यम्) **अदिखादिनीवहीनां प्रतिषेधो वक्तव्यः ॥**

(प्रदीपः) **अदिखादीति ।** अदिखाद्योः प्रत्यवसानार्थत्वात्प्राप्तिः । नीवह्योर्गत्यर्थत्वात् ॥ यद्यपि न **गतिहिंसार्थेभ्य** इत्यत्र **न वहिर्गत्यर्थ** इत्युक्तं भाष्ये । तथापि वहेरनियन्तृकर्तृकस्येत्यभिधानाय वहेरुपक्षेपः ॥

(उद्द्योतः) **इत्युक्तं भाष्ये इति ।** तच्च तत्रैव निरूपितम् । अत एव न वेति सूत्रे हृक्रोरित्यस्योभयत्र विभाषात्वमुक्त्वाऽप्राप्ते हरति भारं देवदत्तो हारयति भारं देवदत्तमिति प्रापणार्थे उदाहृतः । विपूर्वो हरतिर्गत्यर्थ इति च कैयटः । एवं च वहेः प्रतिषेधो नापूर्वः ॥ **तथापीति ।** एवं च नियन्तृकर्तृकवहेरुपसंख्यानं कार्यमिति तात्पर्यम् ॥ नयतेस्तु गत्युपसर्जनं प्रापणमर्थ इति गत्यर्थकत्वमस्त्येव ॥ प्रापयतेस्तु शुद्धं प्रापणमेव वहिवदर्थ इति न स गत्यर्थ इति बोध्यम् ॥

(उदाहरणभाष्यम्)

अत्ति देवदत्तः 'आदयते देवदत्तेन' ॥

(मतान्तरभाष्यम्)

अपर आह—सर्वमेव प्रत्यवसानकार्यमदेर्न भवतीति वक्तव्यं परस्मैपदमपि ॥

(प्रदीपः) **परस्मैपदमिति । निगरणचलनार्थेभ्यश्चेति प्राप्तम् ॥**

(बाधकभाष्यम्)

इदमेकमिष्यते—"क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः" 'इदमेषां जग्धम्' ॥

(उद्द्योतः) भाष्ये **इदमेकमिष्यते इति ।** एवं च **सर्वमेवे**त्यस्यार्थः परस्मैपदकर्मत्वयोः प्रतिषेधो वक्तव्य इत्यर्थः ॥

(उदाहरणभाष्यम्)

खादि—खादति देवदत्तः, 'खादयति देवदत्तेन' ॥ नी—नयति देवदत्तः 'नाययति देवदत्तेन' ॥

(१११८ विशेषवार्तिकम् ॥ ६ ॥)

॥ * ॥ वहेरनियन्तृकर्तृकस्य ॥ * ॥

(भाष्यम्) वहेरनियन्तृकर्तृकस्येति वक्तव्यम्। वहति भारं देवदत्तः 'वाहयति भारं देवदत्तेन' ॥ अनियन्तृकर्तृकस्येति किमर्थम्?। वहन्ति बलीवर्दा यवान् 'वाहयति बलीवर्दान्यवान्' ॥

(प्रदीपः) वहेरिति। नियन्ता सारथिः ॥

(उद्द्योतः) सारथिरिति। पशुप्रेरक इत्यर्थः। अन्यथा रथप्रेरक एव सारथिशब्दस्य प्रसिद्धत्वेन भाष्योदाहरणासङ्गतेरिति बोध्यम् ॥

(१११९ आक्षेपवार्तिकम् ॥ ७ ॥)

॥ * ॥ भक्षेरहिंसार्थस्य ॥ * ॥

(भाष्यम्) भक्षेरहिंसार्थस्येति वक्तव्यम्। भक्षयति पिण्डीं देवदत्तः 'भक्षयति पिण्डीं देवदत्तेन' ॥ अहिंसार्थस्येति किमर्थम्?। भक्षयन्ति यवान्बलीवर्दाः 'भक्षयति बलीवर्दान् यवान्' ॥

(प्रदीपः) भक्षेरिति। अणिकर्तेति हेतुमण्णिचो निषेधाच्चुरादिण्यन्तोऽप्यण्यन्त एवेति प्राप्तिः ॥ भक्षयन्ति यवानिति। क्षेत्रस्थानां प्ररोहाद्यवस्थायां यवानां भक्षणाद्धिंसा भवति। तदवस्थायां कैश्चिच्चैतन्यस्याभ्युपगमात्। परकीययवभक्षणे वा परो हिंसितो भवति। हिंसाङ्गे भक्षणेऽत्र भक्षिर्वर्तते ॥

(उद्द्योतः) ननु भक्षयतेर्नित्यण्यन्तत्वेनाणौ कर्त्रभावादाह—अणि कर्तेति। णावित्यत्र सर्वगत्यर्थादिभ्यो हेतुमण्णिच एव संभवेन तस्यैव ग्रह इति भावः। भक्षेः प्रत्यवसानार्थत्वात्प्राप्तिः। वार्तिके प्रतिषेध इति शेषः ॥ पिण्ड्या अप्राणित्वादुदाहरणे भक्षेरहिंसार्थत्वम् ॥ ननु यवानामप्यचेतनत्वात्तद्विषयस्यापि कथं हिंसार्थत्वमत आह—क्षेत्रस्थानामिति। इदमुपलक्षणं बीजावस्थानामपि भक्षणे हिंसासत्त्वात् ॥ हिंसाङ्ग इति। इदमुभयसाधारणम्। तत्राद्ये यवान् हिंसन् भक्षयतीत्यर्थः, द्वितीये तु परानित्यध्याहार्यम्। परान् हिंसन् यवान् भक्षयतीत्यर्थः। अत्राद्यमेव युक्तं भाष्यस्वरसादित्याहुः ॥ उदाहरणकक्षायां भक्षयन्तीति बहुवचनपाठे तत्स्वामिन इति शेषः ॥

(कालादिकर्मकाणामकर्मकत्वाधिकरणम्)

(११२० आक्षेपवार्तिकम् ॥ ८ ॥)

॥ * ॥ अकर्मकग्रहणे कालकर्मणामुपसंख्यानम् ॥ * ॥

(भाष्यम्) अकर्मकग्रहणे कालकर्मणामुपसंख्यानं कर्तव्यम्। मासमास्ते देवदत्तः 'मासमासयति देवदत्तम्'। मासं शेते देवदत्तः 'मासं शाययति देवदत्तम्' ॥

(प्रदीपः) कालकर्मणामिति। कालग्रहणेन साहचर्यात् पूर्वं सहनिर्दिष्टत्वाद्भावाध्वदेशानामपि ग्रहणम्। वक्ष्यमाणन्यायस्य तुल्यत्वाद् वा ॥

(उद्द्योतः) तुल्यत्वाद्वेति। वाशब्दश्चार्थः ॥

(११२१ समाधानवार्तिकम् ॥ ९ ॥)

॥ * ॥ सिद्धं तु कालकर्मणामकर्मकवद्वचनात् ॥ * ॥

(भाष्यम्) सिद्धमेतत् ॥ कथम्?। कालकर्मका अकर्मकवद्भवन्तीति वक्तव्यम् ॥

(प्रदीपः) सिद्धं त्विति। तेन मासमास्यते देवदत्तेनेत्यादावकर्मकेभ्यो भावे विधीयमाना लादयः सिद्धा भवन्ति। स्वाश्रयं चाव्यावृत्तं कर्मत्वम्। तेन मास आस्यते देवदत्तेनेत्यादौ कर्मण्यपि भवन्ति ॥

(उद्द्योतः) नन्वकर्मकवद्भावे कर्मणि लो न स्यादत आह—स्वाश्रयमिति। सकर्मकेत्यत्र कर्ममात्रस्य ग्रहणादिति भावः। अकर्मकेत्यत्र निषेध्यकोटौ त्वन्तरङ्गस्यकर्मण एव ग्रहणमिति तात्पर्यम् ॥

(तृतीयाक्षेपभाष्यम्)

तत्तर्हि वक्तव्यम्? ॥

(समाधानभाष्यम्)

न वक्तव्यम्। अकर्मकाणामित्युच्यते। न च केचित्कालभावाध्वभिरकर्मकाः, त एवं विज्ञास्यामः—क्वचिद्ये अकर्मका इति ॥

(प्रदीपः) न च केचिदिति ॥ ननु क्रियामात्रविवक्षायां कालादीनामविवक्षितत्वात् तैरप्यकर्मकत्वं भवत्येव। यथा शेते देवदत्तो न भुङ्क्ते इति ॥ अत्राहुः—अत्यन्ताविद्यमानकर्माणो धातवोऽकर्मकग्रहणेन गृह्यन्ते न त्वविवक्षितकर्माणः। अन्यथा पचादीनामपि कर्माविवक्षायामकर्मकनिबन्धनानि कार्याणि भवेयुः। अकर्मकशब्दस्य च धात-

वोऽन्यपदार्थत्वेनाश्रीयन्ते न त्वर्थाः । अर्थाश्रयणे हि कर्माविवक्षायामर्थस्याकर्मकव्यपदेशः स्यात् । धातुष्वाश्रीयमाणेषु कचिदपि कर्मसंबन्धदर्शनेन सारूप्यात्त एवैत इति तत्त्वप्रत्ययविषया नाकर्मकत्वेन व्यपदिश्यन्ते । अर्थास्तु कारकादिभेदाद्भिन्ना एवेत्यन्ये सकर्मका अन्य एवाकर्मका इति स्याद् व्यपदेशः । यदा त्वर्थस्यापि स्वतो नास्ति भेद इति दर्शनं तदार्थेष्वप्यन्यपदार्थेष्वदोषः ॥ **कचिदिति** । द्रव्य एव कर्मणि सत्यकर्मका इत्यर्थः ॥

(उद्योतः) **गृह्यन्त इति** । इह शास्त्र इत्यर्थः । तदेवाह—**अन्यथेति** ॥ **कर्माविवक्षायामिति** । तदविवक्षा हि द्वेधा,—तदन्वययोग्यधात्वर्थत्यागात्, सत्येव तस्मिन्नर्थे तत्र कर्मत्वेनान्वयाविवक्षायां संबन्धित्वेनान्वयस्य विवक्षणाद्वेति ॥ **कार्याणि लादयः** ॥ अत्रारुचिबीजं तु लः **कर्मणी**त्यादिशास्त्रे एवं वक्तुमशक्यम् । कृतपूर्वी कटमित्यत्र कस्याविवक्षितकर्मतया भावे साधनस्य **कर्तृकर्मणो**रिति भाष्यादौ स्पष्टत्वात् ॥ **अकर्मकशब्दस्य** चेत्यादि तदुपपादनमप्यनुचितं कर्मसंज्ञाया अर्थसंज्ञात्वेनार्थानामेवान्यपदार्थत्वस्यौचित्याद् । **अर्थस्यापि स्वतो नास्ति भेद** इति दर्शनमप्यसंगतमेव, धातूनां नानार्थत्वोच्छेदापत्तेः ॥ तस्मादयमर्थः—किमकर्मकशब्दे कर्मपदस्य **कर्मसंज्ञाप्रयोजके** लक्षणया 'न विद्यते कर्मसंज्ञाप्रयोजकोर्थो येषां धातूनाम्' इत्यर्थः, उत 'कर्मरहितार्थप्रतिपादकानाम्' इत्यर्थः । लक्षणोभयत्र तुल्या तत्र नाद्य इत्याह—भाष्ये-**न च केचिदिति** । तथा च कर्मसंज्ञाप्रयोजकार्थरहितानामित्यर्थे **सर्वेषां तदर्थसम्भवेनाकर्मकाणा**मित्यस्योदाहरणासम्भव इत्यर्थः । अन्त्येऽविवक्षितकर्मतयोदाहरणसम्भवो वाच्यः । न च कालस्य क्रियामात्रेणाकाङ्क्षिततया तदविवक्षाऽसम्भवः । आख्यातार्थकालेनैव तदाकाङ्क्षाशान्त्या बाह्यकालकर्मणोऽविवक्षासम्भवात् । एवं च सति गत्यादिसूत्रे तुल्यजातीयापेक्षतया नियमस्य सकर्मकविषयतयाऽकर्मकविषये **कर्तुरीप्सिततम**मित्यनेन तदुपपत्तावकर्मकग्रहणं व्यर्थं स्यात् । तस्मात्सामर्थ्यं मनसि निधायाह—**तदेव**मित्यादि । एतच्च सामान्यापेक्षं ज्ञापकं शास्त्रेऽकर्मकपदमात्रे ईदृशार्थग्रहणमिति ॥ **कचिदि**त्येतद् व्याचष्टे—**द्रव्य एव कर्मणि सतीति** । सतीत्यस्य प्रतियोगिनि सतीति शेषः । एवं च कालाद्यतिरिक्तकर्मप्रतियोगिकाभाववन्त इत्यर्थः । तादृशाश्च सर्वथा द्रव्यकर्माभाववन्तः शेत्यादयः, अविवक्षितकर्माणश्चेत्युभयेपि । प्रयोगानुसारित्वाच्चाविवक्षायाः पचादिष्वविवक्षया नाकर्मकत्वनिबन्धनकार्याणि । न चैवमपि तुल्यजातीयतया सकर्मकविषयनियमेन सिद्धावकर्मकग्रहणं व्यर्थम्, सकर्मकत्वेन कालादिकर्मकाणामपि ग्रहणेन तद्विषयनियमस्याप्यापत्तौ मासमासयति देवदत्तमित्यसिद्ध्यापत्तेः । प्रतियोगिसमर्पककर्मपदेन तु न कालादीनां ग्रहणमेतत्सामर्थ्यादिति न दोषः । वस्तुतो भाष्ये **कचिदि**त्यस्य कालादीनां कर्मत्वप्रयोजकव्याप्त्यादिरहितेऽर्थ इत्यर्थः । कैयटोक्तव्याख्यायां हि **कालभावाध्वभि**रिति पूर्वं तृतीयानिर्देशात्केनचिदित्येव वदेत् । एवं च तदवस्थायामकर्मकत्वेनाकर्मकत्वव्यवहारो धातूनामकर्मकपदसामर्थ्याच्च तदवस्थायां कर्मरहिता गृह्यन्ते इति बोध्यम् ॥

(समाधानान्तरभाष्यम्)

अथ वा येन कर्मणा सकर्मकाश्चाकर्मकाश्च भवन्ति तेनाकर्मकाणाम् । न चैतेन कर्मणा कश्चिदप्यकर्मकः ॥

(प्रदीपः) **अथवा येनेति** । संभवव्यभिचाराभ्यां विशेषणविशेष्यभावे सर्वत्र वस्तुस्थित्याऽविवक्षिता अपि कालादयः सन्तीति न तैः केचिदकर्मका इत्यर्थः ॥

(उद्योतः) भाष्ये—**न चैतेनेति** । कालादिनेत्यर्थः । तद्व्याचष्टे—**सम्भवेति** । कालादीनां तु व्यभिचारो नास्त्युक्तरीत्या व्यापनादिरूपधात्वर्थपूर्वके स्वार्थे सकर्मकाणामपि वृत्तेस्तेषामपि तत्सम्भवादिति भावः । अयं भावः—कालादेरपि प्रतियोगिभूतकर्मपदेन [कर्म]ग्रहणेऽकर्मको धातुरसम्भवीति सामर्थ्याद्द्रव्यकर्मण एव प्रतियोगित्वेन ग्रहणमिति ॥ ननु तदविवक्षायां तत्सम्भव इत्यत आह—**वस्तुस्थित्येति** । धातुरेवान्यपदार्थ इति भावः ॥ वस्तुतो व्याप्त्यादिविवक्षासत्त्वेप्यकर्मकत्वोपपत्तिर्दर्श्यते—**अथवेति** भाष्येण । उपपत्तिस्तूक्तैव । **न चैतेने**त्यादिना भाष्येण व्यभिचाराभाव उच्यते ॥

(समाधानान्तरभाष्यम्)

अथ वा यत्कर्म भवति न च भवति, तेनाकर्मकाणाम् । न चैतत् कर्म कचिदपि न भवति ॥ गतिबुद्धि—॥ १२ ॥

(प्रदीपः) **अथ वेति** । अकर्मकश्रुत्यान्तरङ्गं द्रव्यकर्म निषिध्यते न बहिरङ्गं कालादिकर्म । तथाहि—पूर्वं क्रियाया द्रव्यकर्मणा सह संबन्धो भवति पश्चात् कालादिभिः परिमाणनिर्धारणाय । तथा चोक्तम्—

शक्तिप्रमाणसंख्यादेर्द्रव्यधर्मात्प्रवर्तते ।
क्रियासु कालयोगोतः प्राग्योगो द्रव्यकर्मणा ॥ इति

सूत्रं चेदं नियमार्थमिति **आकडारसूत्र** उक्तं तत एवावधार्यम् ॥ ५२ ॥

(उद्योतः) पूर्वस्माद्भेदव्युत्पादनायान्तरङ्गत्वतात्पर्यकतया योजयति—**अकर्मकेति** ॥ **पूर्वं क्रियाया इति** । तदुद्देशेनैव क्रियाप्रवृत्तेरिति भावः ॥ **शक्तिप्रमाणेति** । द्रव्यधर्मरूपात् श-

ल्यादेः सकाशात् क्रियासु कालयोगः प्रवर्तते इत्यर्थः । तत्र वृक्षे-ष्वेषा वसन्तादिकालयोगः पल्लवजन्मादेः । प्रमाणवशाद् यथा दीर्घ-शष्कुल्यादिचर्वणस्य दण्डादिकालयोगः । संख्यावशाद् यथा नाना-द्रव्यकर्मकपाकस्य ॥ सकर्मकपदे तु कालादेः कर्मसंज्ञाविधानसामर्थ्यात् कालादिकर्मणोपि ग्रहणम् । अत एवास्यते मास इति कर्मणि लः सिध्यति । अत्रैतत्सूत्रस्थाकर्मकपदवत्सकर्मकपदे कालादिकर्मणोऽग्रहणे तात्पर्यग्राहकाभावादिति तत्त्वम् ॥ न चैतत्कर्मेतिभाष्येण द्रव्य-कर्मणो व्यभिचार एव दर्श्यते न त्वन्तरङ्गत्वमिति चिन्त्यम् ॥ वस्तुतो द्वितीयपक्षोक्तमेवार्थं भङ्ग्यन्तरेणाह—अथ वेति । न चै-तेनेत्यादेः [कश्चिदप्यकर्मक] एतेन कर्मणा रहितो नेत्यर्थेन सकर्म-काणामेतत्कर्माभावादेषामपि व्यभिचारित्वमिति कश्चिद् भ्राम्ये-त्तद्भ्रमनिवृत्त्यर्थं तस्यार्थस्य पुनः कथनम् । एवं चाकर्मकपदेन व्यभि-चारिद्रव्यकर्मरहितानामित्यर्थबोधनेन मासादिकर्मसत्त्वेप्यकर्मकत्वमि-त्येतत्पक्षेर्थः । न त्वेतद्भाष्यबलेनात्यन्ताविद्यमानकर्मकाणामेवात्र ग्रहणमिति वक्तुं युक्तम् । कालाध्वनोरिति सूत्रे लः कर्मणीति-सूत्रस्थाकर्मकपदविषयेपीदृशस्यैव भाष्यस्य सत्त्वेन तत्राप्यत्यन्तावि-द्यमानकर्मकाणामेव ग्रहणापत्तौ पूर्वोक्तकृतपूर्वीत्यादिभाष्यासङ्गत्या-पत्तेः ॥ किं चात्यन्ताविद्यमानकर्मकाणामत्र ग्रहणमिति पक्षे लुना-तेर्निर्वृत्तप्रेषणाण्णिचि लावयति केदारं देवदत्त इति णेरणाविति सूत्रस्थकैयटप्रयोगे केदारस्य कर्मत्वानापत्तिरिति दिक् ॥ ५२ ॥

(१९३ कर्मसंज्ञासूत्रम् ॥ १।४ । ३ आ. १८ सू.)

२९३ हृक्रोरन्यतरस्याम् ॥१।४।५३॥

(प्रदीपः) हृक्रोर ॥ ५३ ॥ उभयत्र विभाषेयमिति नवेति विभाषेत्यत्रोक्तम् ॥

(उद्द्योतः) हृक्रोर ॥ ५३ ॥ इत्यत्रोक्तमिति । वार्तिक-कृतेति शेषः ॥

(न्यूनतापूर्त्यधिकरणम्)

(११२२ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ हृक्रोर्वावचनेऽभिवादिदृशोरात्मनेपद उपसंख्यानम् ॥ * ॥

(भाष्यम्) हृक्रोर्वावचने अभिवादिदृशोरात्मने-पद उपसंख्यानं कर्तव्यम् । अभिवदति गुरुं देव-दत्तः 'अभिवादयते गुरुं देवदत्तेन । अभिवादयते गुरुं देवदत्तम्' । पश्यन्ति भृत्या राजानम् 'दर्शयते भृत्यै राजा, दर्शयते भृत्यान् राजा' ॥

(प्रदीपः) अभिवादिदृशोरिति । अभिवादयताव-प्राप्ता कर्मसंज्ञा पक्षे विधीयते दृशेर्बुद्ध्यर्थत्वान्नित्यप्राप्ता पक्षे निवर्त्यते ॥

(अनुयोगभाष्यम्)

कथं चात्रात्मनेपदम् ?॥

(उद्द्योतः) भाष्ये कथं चात्रात्मनेपदमिति । एतद्वा-र्तिकोदाहरणयोरित्यर्थः । अभिवादयतावणौ कर्मणो णौ कर्तृत्वा-भावाद्, दर्शयतावणौ कर्मातिरिक्तकर्मणः सत्त्वादिति प्रश्नः ॥

(समाधानभाष्यम्)

एकस्य "णेरणौ" इति, अपरस्य "णिचश्च" इति ॥

(उद्द्योतः) एकस्येति । आद्यान्यस्य दृशेरित्यर्थः अणौ कर्तृकर्मातिरिक्तकर्माभावो विवक्षित इति भावः ॥ अपरस्येति । आद्यस्याभिवादयतेरित्यर्थः । उक्त आशयः ॥ ५३ ॥

(१९४ कर्तृसंज्ञासूत्रम् । १ । ४ । ३ आ. १९ सू.)

२९४ स्वतन्त्रः कर्ता ॥ ५४ ॥

(स्वतन्त्रशब्दार्थनिर्णयाधिकरणम्)

(आक्षेपभाष्यम्)

किं यस्य स्वं तन्त्रं स स्वतन्त्रः ?॥

(प्रदीपः) स्वतन्त्रःकर्ता ॥ ५४ ॥ किं यस्येति । तन्तुवायस्य स्वतन्त्रशब्दवाच्यत्वाद्विशेषानुपादानाच्च प्रश्नः ॥

(उद्द्योतः) स्वतन्त्रः कर्ता ॥ ५४ ॥ स्वं तन्त्रमिति । विततास्तन्तवस्तन्त्रम् ॥ किमयं बहुव्रीहिरिति प्रश्नतात्पर्यम् ॥

(दूषणप्रत्याक्षेपभाष्यम्)

किं चातः ? ॥

(प्रत्याक्षेपसमाधानदूषणभाष्यम्)

तन्तुवाये प्राप्नोति ॥

(प्रदीपः) तन्तुवाय इति । यद्यपि तन्तुवायो वयति भुङ्क्ते इत्यादौ तन्तुवायस्य कर्तृसंज्ञेष्यते तथापि विशेषविहित-त्वात् परत्वाच्चापादानादिसंज्ञाविषयेपि सा प्राप्नोति । ब्राह्मणो-धीत इत्यादौ च ब्राह्मणादेर्न प्राप्नोतीति दोषः ॥

(उद्द्योतः) विशेषविहितत्वादित्यभ्युच्चयः निरवकाशत्वाभा-वात् ॥ अपादानादिसंज्ञेति । तन्तुवायाद् गृह्णातीत्यादौ ॥ ब्राह्म-णादेर्नेति । तन्तुवाय इत्यस्य भाष्यस्य तत्रैवेत्यर्थं इति भावः ॥

(समाधानभाष्यम्)

नैष दोषः । अयं तन्त्रशब्दोऽस्त्येव विताने व-र्तते । तद्यथा—आस्तीर्णं तन्त्रम्, प्रोतं तन्त्रमिति । विताननमिति गम्यते ॥ अस्ति प्राधान्ये वर्तते । तद्यथा—स्वतन्त्रोऽसौ ब्राह्मण इत्युच्यते । स्वप्रधान इति गम्यते ॥ तद्यः प्राधान्ये वर्तते तन्त्रशब्दस्त-स्येदं ग्रहणम् ॥

(प्रदीपः) वितान इति । वितन्यत इति वितानम् ॥ स्वतन्त्रोऽसौ ब्राह्मण इति । स्वशब्द आत्मवाची । स आत्मा

तन्त्रं प्रधानं यस्य स स्वतन्त्र उच्यते । तत्र कारकाधिकारात् क्रियासिद्धौ प्राधान्यस्योपयोगात्तन्तुवायस्यापि तन्तुवायरूपतया तत्रानुपयोगात् प्रधानवाचिनः स्वतन्त्रशब्दस्येह ग्रहणम् । अनेककारकसाध्यायामपि क्रियायां यथा कस्य चित् स्वातन्त्र्यं तथा कारकसूत्रे प्रतिपादितम् । यस्य धातुना व्यापारोऽगुणभावेनोच्यते स एवासौ स्वतन्त्र इत्येतदपि तत्रैव भाष्यकृता प्रतिपादितम् ॥

(उद्योतः) वितन्यत इति । स च सन्निवेशविशेषविशिष्टस्तन्तुसमूहः ॥ स्वतन्त्र उच्यत इति । यथा कथंचिद् व्युत्पन्नोऽयं प्रधानार्थे रूढ इति भावः ॥ प्राधान्ये वर्तमानस्यैव ग्रहणं कुत इत्यत आह—तत्रेति । क्रियासिद्धौ यः स्वतन्त्र इत्यर्थे प्राधान्यस्यैवान्वययोग्यत्वम् ॥ तन्तुवायरूपतयेति । कारक इत्यनेन क्रियामात्रस्योपस्थितेस्तत्सिद्ध्यं तत्त्वेनानुपयोग इत्यर्थः । बहुलक्ष्यसंस्कारानुरोधात् प्रधानस्यैव ग्रहणमित्यपि बोध्यम् ॥ ननु किं प्राधान्यं कर्तुरित्यत आह—अनेकेति । सकलकारकप्रवर्तकत्वादिति भावः ॥ नन्वेवं स्थाली पचतीत्यादि न स्यादत आह—यस्य धातुनेति । अगुणभावेन प्राधान्येन ॥ स्वतन्त्र इति । स्वातन्त्र्येण विवक्षित इत्यर्थः । तच्चारोपितमनारोपितं वेत्यन्यत् । कर्तृप्रत्ययसमभिव्याहारे प्रधानीभूतधात्वर्थव्यापाराश्रयो हि सः । तादृश एव च सकलकारकप्रवर्तकः । प्रायेण कर्मप्रत्ययसमभिव्याहारे फलव्यापारयोर्व्यत्यासदर्शनात्समभिव्याहारे इत्यन्तमित्यादि निरूपितं मञ्जूषायाम् ॥

(प्रयोज्यस्य कर्तृसंज्ञासाधनाधिकरणम्)

(११२३ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ स्वतन्त्रस्य कर्तृसंज्ञायां हेतुमत्युपसंख्यानमस्वतन्त्रत्वात् ॥ * ॥

(भाष्यम्) स्वतन्त्रस्य कर्तृसंज्ञायां हेतुमत्युपसंख्यानं कर्तव्यम् । पाचयत्योदनं देवदत्तो यज्ञदत्तेनेति ॥ किं पुनः कारणं न सिध्यति ? । अस्वतन्त्रत्वात् ॥

(प्रदीपः) हेतुमतीति । प्रयोज्य इत्यर्थः । यथा कर्तृसन्निधौ करणादीनां नास्ति स्वातन्त्र्यं तथा प्रयोजकसन्निधौ प्रयोज्यस्य पारतन्त्र्यात् स्वातन्त्र्याभावात् कर्तृसंज्ञाया अप्रसङ्गात् पाचयत्योदनं देवदत्तेनेति कर्तृतृतीया न प्राप्नोति । तत्प्रयोजक इत्यत्र च तच्छब्देन परामर्शो नोपपद्यते ॥

(उद्योतः) ननु हेतुमतिचेत्यत्र हेतुमच्छब्देन प्रयोजकव्यापार उच्यते न स तत्र संज्ञ्यतेऽत आह—प्रयोज्य इति । स एवात्र हेतुमच्छब्दार्थत्वेन विवक्षित इत्यर्थः ॥ स्वातन्त्र्यमिति । उद्धृतमिति शेषः ॥ दूषणान्तरमाह—तत्प्रयोजक इति । तत्र हि तत्पदेन स्वतन्त्र एव पूर्वसूत्रोपात्तः परामृश्यते ॥

(११२४ समाधानवार्तिकम् ॥ २ ॥)

॥ * ॥ न वा स्वातन्त्र्याद् इतरथा ह्यकुर्वत्यपि कारयतीति स्यात् ॥ * ॥

(भाष्यम्) न वा कर्तव्यम् । किं कारणम् ? । स्वातन्त्र्यात् । स्वतन्त्रोऽसौ भवति ॥ इतरथा ह्यकुर्वत्यपि कारयतीति स्यात् । यो हि मन्यते-नासौ स्वतन्त्रः, अकुर्वत्यपि तस्य कारयतीत्येतत्स्यात् ॥

(प्रदीपः) न वेति । प्रयोजकसन्निधानेपि प्रयोज्यस्य करणादिसाधनविनियोगादिना स्वातन्त्र्यस्य क्रियासिद्धौ सद्भावादित्यर्थः ॥ अकुर्वत्यपीति । यदि प्रयोज्यस्य स्वातन्त्र्यं न स्यान्नैवासौ साधनान्तरविनियोगादिना क्रियां कुर्यात् तथा चाकुर्वत्यपि प्रयोज्ये प्रयोजकः कारयतीति व्यपदिश्येत ॥

(उद्योतः) क्रियासिद्धाविति । स्वक्रियासिद्धावित्यर्थः । अयं भावः—स्वक्रियाकारकप्रवर्तकत्वरूपस्वातन्त्र्यमस्यास्त्येव परप्रेर्यत्वेपि ॥ ननु प्रेरणायाः क्रियाविषयत्वात्कथमकुर्वति कारयतीति प्रयोगोऽत आह—यदीति । साधनान्तरविनियोगेन क्रियासाधकत्वमेव हि स्वातन्त्र्यम् ॥ मूले आदिपदार्थः क इति चिन्त्यम् ॥ व्यपदिश्येतेति । तदापि तस्यौपसंख्यानिककर्तृत्वेन कर्तुः प्रयोजकत्वात्तस्य हेतुत्वे णिजापत्तिः । एवं चोपसंख्यानमतिव्यापकमिति भावः ॥

(११२५ समाधानसाधकवार्तिकम् ॥ ३ ॥)

॥ * ॥ नाकुर्वतीति चेत्स्वतन्त्रः ॥ * ॥

(भाष्यम्) न चेदकुर्वति तस्मिन्कारयतीत्येतद्भवति । स्वतन्त्रोऽसौ भवति ॥

(उद्योतः) भाष्ये न चेदकुर्वति तस्मिन् कारयतीत्येतद्भवतीत्यनन्तरं किं तु कुर्वत्येवेति शेषः ॥ स्वतन्त्रोऽसाविति । असावुपसंख्यानलभ्यकर्तृसंज्ञकः स्वतन्त्र इत्यर्थः । एवं चोपसंख्यानातिप्रसङ्गवारणाय वार्तिकेपि स्वतन्त्रपदमनुवर्त्य तत्सामर्थ्याद्गौणार्थकत्वमाश्रित्य कुर्वतः स्वतन्त्रत्वात्तस्यैव कर्तृसंज्ञा नाकुर्वत इति वाच्यमित्याह ॥

(आक्षेपभाष्यम्)

शक्यं तावदनेनोपसंख्यानं कुर्वता वक्तुम् कुर्वन्स्वतन्त्रोऽकुर्वन्नेति ॥

(प्रदीपः) शक्यं तावदिति । उपसंख्यानवाद्यपि प्रयोज्यस्य स्वातन्त्र्यमस्तीत्यभ्युपगच्छतीति प्रतिपाद्यते । प्रयो-

ज्यस्य स्वातन्त्र्येण स्वव्यापारं प्रत्यप्रवर्तनात् किलोपसंख्यानमारभ्यते। तेन चेदमवश्याभ्युपगन्तव्यम्—यः करोति स स्वतन्त्रः न त्वकुर्वन्निति। एवं चेत् प्रयोजकसन्निधानेपि स्वार्थदर्शनात् प्रयोज्यः करोति नान्यथेति तस्य स्वातन्त्र्यमस्त्येव। तथा चोक्तं भाष्यकृता—**न हि कश्चित्परोनुग्रहीतव्य इति प्रवर्तते, सर्व इमे स्वभूत्यर्थं यतन्त इति ॥**

(उद्योतः) **शक्यं तावदिति।** एवंन सूत्र एव गौणमुख्यसाधारणस्वतन्त्रपदार्थमाश्रित्य वार्तिकं न कार्यमिति भावस्तदाह—**उपसंख्यानवादीति ॥ तेन चेदमिति।** उक्तदोषवारणायेत्याशयः। अकुर्वन्नितीत्यन्तमभ्युपगमे कर्म ॥ **एवं चेदिति।** प्रेरणोत्तरमप्यकरणं चेदित्यर्थः॥ **स्वातन्त्र्यमस्त्येवेति।** अन्यथा स्वार्थाभावेऽपि कुर्यादित्यर्थः। एवं च सूत्रेणैव सिद्धे उपसंख्यानं व्यर्थमिति भावः॥

(समाधानभाष्यम्)

साधीयो ज्ञापकम्। प्रेषिते च किलायं क्रियां चाक्रियां च दृष्ट्वाऽध्यवस्यति—कुर्वन्स्वतन्त्रोऽकुर्वन्नेति। यदि च प्रेषितोसौ न करोति स्वतन्त्रोसौ भवतीति ॥ स्वतन्त्रः कर्ता ॥ ५४ ॥

(प्रदीपः) **प्रेषिते चेति।** कर्तुरधिकरणत्वेन विवक्षितत्वात्सप्तमी ॥ **क्रियामिति।** स्वार्थदर्शनादिच्छायां सत्यां क्रियां, तददर्शने त्वक्रियाम् ॥ **यदि चेति।** स्वार्थादर्शनादिच्छायामसत्यामित्यर्थः ॥ ५४ ॥

(उद्योतः) भाष्ये—**ज्ञापकम्** अनुमापकम् ॥ **अयम्** उपसंख्यानवादी॥ **प्रेषिते।** पुरुषे॥ **क्रियाम्।** क्रियाप्रयोज्यमनेन कारयतीति प्रयोगम्। **अक्रियां** तत्प्रयोज्यमनेन कारयतीति प्रयोगाभावं च दृष्ट्वा निश्चिनोति कुर्वन् स्वतन्त्रोऽकुर्वन्नेतीत्यर्थः। एतेन प्रेषिते क्रियादर्शनादेव तस्य पारतन्त्र्यनिर्णय इति स एव कथं स्वातन्त्र्ये हेतुरित्यकुर्वन्न स्वतन्त्र इत्यस्य प्रकृतेऽनुपयोगश्चेति परास्तम् ॥ एवमुपसंख्यानारम्भेऽतिप्रसङ्गवारणाय स्वतन्त्रपदसंबन्धापमिधायैवं सति मुख्यस्वातन्त्र्यग्रहणेपि प्रयोज्यस्य तदस्तीत्याह—**यदि चेति** भाष्ये। असेच्छायामसत्यामिति शेषः। तदाह—**स्वार्थादर्शनादिति।** एवं च यद्ययमस्वतन्त्रः स्यात्सर्वथा कुर्यादेव कदाचिन्न करोत्यपि, तस्मात्स्वतन्त्र इति भावः॥ एवं च स्वेच्छाधीनप्रवृत्तिनिवृत्तिकत्वं स्वातन्त्र्यमित्युक्तं तस्यैव च प्रागुक्तं सकलकारकप्रयोक्तृत्वम्। तच्चारोपितमनारोपितं च संज्ञोपयोगि। तत्रारोपित स्थाल्यादौ, अन्त्यं पुरुषे। यस्य च स्वातन्त्र्यविवक्षा तद्व्यापार एव च धातुना प्राधान्येनोच्यते शब्दशक्तिस्वभावात्। तदुक्तं कारके इति सूत्रे भाष्ये—**संभवनक्रियां धारणक्रियां च कुर्वती स्थाली पचतीति यदोच्यते तदा तत्र व्यापारे** वर्तते स्थालीस्थे च यत्ने कथ्यमाने स्थाली स्वतन्त्रेति। आरोपितस्वातन्त्र्यवतीति तदर्थः ॥ **कर्तुरधिकरणत्वेनेत्यादि** चिन्त्यम्। नह्यत्र वाक्ये प्रेषितो दर्शनक्रियायामध्यवस्यतिक्रियायां वा कर्ता, अयमित्यस्य कर्तुरुपादानात्। क्रियामित्येतत्कर्मनिरूपितं स्वस्याधिकरणत्वं स्थाल्यां तण्डुलमित्यादिवत्। अन्यथा देवदत्ते पचतीत्यस्याप्यापत्तिः। कर्तृकर्मद्वारा क्रियाश्रयस्यैवाधिकरणत्वाच्च। न च क्रियामित्येतन्निरूपितं कर्तृत्वं, तस्य सत्त्वभूतार्थप्रतिपादकत्वात् ॥ ५४ ॥

(१९५ हेतुसंज्ञासूत्रम् ॥ १।४।३ आ. २० सू.)

२९५ तत्प्रयोजको हेतुश्च ॥ ५५ ॥

(प्रयोज्यस्य स्वतन्त्रस्वसाधनाधिकरणम्)

(११२६ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ प्रैषेऽस्वतन्त्रप्रयोजकत्वाद्धेतुसंज्ञाऽप्रसिद्धिः॥ * ॥

(भाष्यम्) **प्रैषेऽस्वतन्त्रप्रयोजकत्वाद्धेतुसंज्ञाया अप्रसिद्धिः प्राप्नोति। स्वतन्त्रप्रयोजको हेतुसंज्ञो भवतीत्युच्यते। न चासौ स्वतन्त्रं प्रयोजयति ॥**

(प्रदीपः) तत्प्रयोजकः॥५५॥**प्रैष इति।** ननु पूर्वसूत्र एव प्रयोज्यस्य स्वातन्त्र्यमुपपादितं तत्किमर्थं चोद्यते॥ एवं मन्यते-प्रैषादूर्ध्वं प्रयोज्यस्य स्वव्यापारे प्रवर्तनात् स्वातन्त्र्यम्। प्रैषकाले तु स्वव्यापाराप्रवर्तनात् प्रवृत्तौ प्रैषवैयर्थ्यात्स्वातन्त्र्यं नास्ति। तस्य च प्रयोजको न हेतुः स्यात्। ततश्चात्र न णिज्भवेत् ॥ प्रैषग्रहणमध्येषणनिवृत्त्यर्थमिति केचित्। अध्येषणे किल व्यापार्यमाणस्य गुर्वादेः स्वव्यापारे स्वातन्त्र्यमस्तीति। तत्त्वयुक्तम्। न्यायस्य तुल्यत्वात्। तस्मादत्र प्रैषग्रहणेन नियोगमात्रमुच्यते न तु निकृष्टविषय एव नियोगः ॥

(उद्योतः) **तत्प्रयोजके** ॥ ५५ ॥ शेषषष्ठ्या समासः ॥ प्रवर्तनात् स्वातन्त्र्यमित्यस्यास्तु नामेति शेषः ॥

(११२७ समाधानवार्तिकम् ॥ २ ॥)

॥ * ॥ स्वतन्त्रत्वात्सिद्धम् ॥ * ॥

(भाष्यम्) **स्वतन्त्रत्वात्सिद्धमेतत्। स्वतन्त्रमसौ प्रयोजयति ॥**

(प्रदीपः) **स्वतन्त्रत्वादिति।** दृष्टसामर्थ्यो वा संभावितसामर्थ्यो वा क्रियायां स्वातन्त्र्येण समाश्रित एव नियुज्यत इत्यर्थः ॥

(उद्द्योतः) समाश्रितो विवक्षितः ॥

(११२८ समाधानबाधकवार्तिकम् ॥ ३ ॥)

॥ * ॥ स्वतन्त्रत्वात्सिद्धमिति चेत्स्वतन्त्र-परतन्त्रत्वं विप्रतिषिद्धम् ॥ * ॥

(भाष्यम्) यदि च स्वतन्त्रो न प्रयोज्यः, अथ प्रयोज्यो न स्वतन्त्रः, प्रयोज्यः स्वतन्त्रश्चेति विप्रतिषिद्धम् ॥

(प्रदीपः) स्वतन्त्रपरतन्त्रत्वमिति । प्रयोजकसन्निधौ पारतन्त्र्येण स्वातन्त्र्यस्य तिरस्कृतत्वाद्यौगपद्यानुपपत्तिरिति भावः ॥

(११२९ समाधानसाधकवार्तिकम् ॥ ४ ॥)

॥ * ॥ उक्तं वा ॥ * ॥

(भाष्यम्) किमुक्तम् ?। एकं तावदुक्तम्—*न वा स्वातन्त्र्यादितरथा ह्यकुर्वत्यपि कारयतीत्येतत्स्यात्* इति । अपरमुक्तम्—*न वा सामान्यकृतत्वाद्धेतुतो ह्यविशिष्टम्* । *स्वतन्त्रप्रयोजकत्वादप्रयोजक इति चेन्मुक्तसंशयेन तुल्यम्* इति ॥ तत्प्रयोजको ॥ ५५ ॥

इति श्रीमद्भगवत्पतञ्जलिविरचिते व्याकरण-महाभाष्ये प्रथमस्याध्यायस्य चतुर्थपादे तृतीयमाह्निकम् ॥

(प्रदीपः) उक्तं वेति । वक्ष्यमाणस्यापि बुद्ध्या विषयीकृतत्वाद्भूतत्वसमारोपादुक्तं वक्ष्यमाणं चाभेदेनोक्तं वेति निर्दिष्टम् ॥ न वा सामान्यकृतत्वादिति । हेतुमति चेत्यत्र वार्तिककारेणैतदुक्तम् ॥ मुक्तसंशयेनेति । अप्रयुक्तो यः स्वयं करोति तेन तुल्यः प्रयोज्योपीत्यर्थः ॥ ५५ ॥

इत्युपाध्यायजैयटपुत्रकैयटकृते महाभाष्यप्रदीपे प्रथमस्याध्यायस्य चतुर्थे पादे तृतीयमाह्निकम् ॥

(उद्द्योतः) ननु न वा सामान्येत्यादेर्हेतुमति चेत्यत्र वक्ष्यमाणतयाऽपरमुक्तमित्यसङ्गमत आह—वक्ष्यमाणस्यापीति । अयं हि न वा सामान्येति वार्तिकार्थः—कंसंघातयतीत्यादौ हेतुमति चेत्येव सिद्धत्वादुपसंख्यानं न कार्यम् ॥ कथं सामान्यकृतत्वमत आह—हेतुत इति । मुख्याद्धेतुतः पौराणिकादिरविशिष्ट इत्यर्थः ॥ स्वतन्त्रप्रयोजकस्य हेतुत्वादयमप्रयोजको हेतुरिति चेदित्यर्थः ॥ ५५ ॥

इति श्रीशिवभट्टसुतसतीगर्भजनागोजी(गेश)भट्टकृते भाष्यप्रदीपोद्द्योते प्रथमस्य चतुर्थे तृतीयमाह्निकम् ॥

(इति विधिशेषप्रकरणे कारकप्रकरणम् ॥)

प्रथमाध्यायस्य चतुर्थपादे

चतुर्थमाह्निकम्

(अथ विधिशेषप्रकरणे निपातसंज्ञाप्रकरणम् ।)

(१९६ अधिकारसूत्रम् ॥ १ । ४ । ४ आ. १ सू०)

२९६ प्राग्रीश्वरान्निपाताः ॥ ५६ ॥

(रेफोच्चारणप्रयोजनाधिकरणम्)

(आक्षेपभाष्यम्)

किमर्थं रेफाधिक ईश्वरशब्दो गृह्यते ?॥

(प्रदीपः) प्राग्रीश्वरात् ॥ ५६ ॥ किमर्थमिति । प्रागीश्वरादित्येव क्रियतां प्रत्यासत्त्याऽधिरीश्वर इतीश्वरशब्दो ग्रहीष्यत इति प्रश्नः ॥

(उद्द्योतः) प्राग्रीश्वरा ॥ ५६ ॥ अधिरीश्वर इतिसूत्रस्थे ईश्वरे इति पदे प्रकृतिभागस्य पूर्वान्तरेफेण सहानुकरणं रीश्वरादिति ॥ नन्वन्यस्यापीश्वरशब्दस्यावधित्वं स्यादत आह—प्रत्यासत्त्येति ॥

(११३० समाधानवार्तिकम् ॥ १ ॥)

॥ * ॥ रीश्वराद्वीश्वरान्मा भूत् ॥ * ॥

(भाष्यम्) रीश्वरादित्युच्यते, वीश्वरान्मा भूदिति—"शकिणमुल्कमुलावीश्वरेतोसुन्कसुनौ" इति॥

(प्रदीपः) वीश्वरादिति । व्यासिन्यायाद्वीश्वरात्प्राक् स्यात् । यदा संहितया सूत्रपाठस्तदा वकारसहित ईश्वरशब्दोस्तीत्येतदभिप्रेत्यैवमुक्तम् ॥

(उद्द्योतः) ननु प्रथमोपस्थितत्वादस्यैव ग्रहणं स्यादत आह—व्यासीति ॥ वीश्वरादिति । तत्रापीश्वरशब्दोस्तीति भावः ॥ वीश्वरशब्दस्य क्वाप्यश्रवणादाह—यदेति ॥

(समाधानबाधकभाष्यम्)

नैतदस्ति प्रयोजनम् । आचार्यप्रवृत्तिर्ज्ञापयति—अनन्तरो य ईश्वरशब्दस्तस्य ग्रहणमिति । यदयं "कृन्मेजन्तः" इति कृतो मान्तस्यैजन्तस्याव्ययसंज्ञां शास्ति ॥

(प्रदीपः) यदयमिति । सेकसेन्प्रभृतीनां णमुल्कमुलोश्च निपातत्वादेवाव्ययसंज्ञायां सिद्धायां कृन्मेजन्त इत्यव्ययसंज्ञाविधानाज्ज्ञापकाद्व्याप्तिर्बोध्यत इत्यर्थः ॥

(११३१ समाधानसाधकवार्तिकम् ॥ २ ॥)

॥ * ॥ कृन्मेजन्तः परोपि सः ॥ * ॥

(भाष्यम्) परोप्येतस्मात्कृन्मेजन्तश्चास्ति तदर्थमेतत्स्यात् ॥

(प्रदीपः) परोपीति। कृत्यार्थे तवैकेनित्यादिरे-जन्तः समुत्रादिश्च मान्तोऽस्ति तदर्थमेतत्स्यादित्यज्ञापकं व्याप्ते-र्बाधस्य॥

(समाधानबाधकभाष्यम्)

यत्तर्ह्यव्ययीभावस्याव्ययसंज्ञां शास्ति तज्ज्ञाप-यत्याचार्यः—अनन्तरो य ईश्वरशब्दस्तस्य ग्रहण-मिति॥

(प्रदीपः) यत्तर्हीति। व्याप्तावाश्रीयमाणायां निपात-त्वादव्ययीभावस्याव्ययसंज्ञा सिद्धैव किं तद्विधानेनेति ज्ञापकं संपद्यते॥

(११३२ समाधानसाधकवार्तिकम्॥ ३॥)

॥ * ॥ समासेष्वव्ययीभावः ॥ * ॥

(भाष्यम्) **समासस्यैतज्ज्ञापकं स्यात्—अव्ययी-भाव एव समासोऽव्ययसंज्ञो भवति नान्य इति॥**

(प्रदीपः) समासेष्विति। तुल्यजातीयव्यावृत्तये नि-यमार्थमेतत्स्यात् न तु व्याप्त्यग्रहणज्ञापनार्थमेतदित्यर्थः॥

(उद्द्योतः) ननु नियमापेक्षया ज्ञापकत्वं युक्तमत आह—तुल्येति। न्यायबाधकल्पने बहुषु शास्त्रबाधः कल्प्यः। नियमे तु सजातीयविषय एवेति लाघवं नियमे इति भावः॥ समासे एत-ज्ज्ञापकमिति भाष्ये ज्ञापकशब्दो नियमपर इति बोध्यम्॥

(समाधानबाधकभाष्यम्)

एवं तर्हि लोकत एतत्सिद्धम्। तद्यथा—लोके आ वनान्ताद्वा उदकान्तात् 'प्रियं पान्थमनुव्रजेत्' इति। य एव प्रथमो वनान्त उदकान्तश्च ततोऽनु-व्रजन्ति॥

(प्रदीपः) एवं तर्हीति। लोके प्रत्यासत्तिराश्रीयते यथा कपिञ्जलानालभेतेति त्रय एवालभ्यन्ते न चतुरा-दयः। शास्त्रे च लोकव्यवहारोऽङ्गीक्रियते इति भावः॥

(उद्द्योतः) ननु लोकन्यायस्य शास्त्रे कथमाश्रयणमत आह—शास्त्रे चेति। लक्ष्यानुरोधात्प्रत्यासत्तिरेवाश्रयिष्यते इति भावः॥ भाष्ये प्रियं प्रोथमिति क्वचित्पाठः। तत्र प्रोथोऽध्वगः। प्रोथोऽस्त्री हयघोणायां ना कट्यामध्वगे त्रिषु। प्रोथोऽध्वगेऽश्वघो-णायां कटिस्त्रीगर्भयोरपीति मेदिनीविश्वोक्तेः॥ यत्तु हरदत्तेन—प्रोथं पर्याप्तमित्यर्थकं क्रियाविशेषणं, प्रोथ पर्याप्ताविति धातोः पचाद-जित्युक्तम्। तदुक्तकोशानुक्तेस्तस्य धातोरभावाच्च प्रकृतेर्थासङ्गतेगूथ-यूथप्रोथा इत्युणादिसूत्रेण थप्रत्ययान्ततया साधनाच्चोपेक्ष्यम्॥

(११३३ समाधानसाधकवार्तिकम्॥ ४॥)

॥ * ॥ लौकिकं चातिवर्तते ॥ * ॥

(भाष्यम्) **द्वितीयं तृतीयं च वनान्तमुदकान्तं चानुव्रजन्ति तस्माद्रेफाधिक ईश्वरशब्दो ग्रही-तव्यः॥**

(प्रदीपः) लौकिकमिति। लौकिकं प्रत्यासत्तिलक्षणं न्यायं लोक एव परित्यजति। स्नेहादिवशाद् द्वितीयमप्युद-कान्तं प्राप्य निवर्तते॥ कपिञ्जलानित्यत्र तु प्रथमातिक्रमे कारणाभावान्न हिंस्यात्सर्वा भूतानीति चतुर्थादिषु निषे-धावताराच्च त्रय एवालभ्यन्ते। इह तु विरोधकाभावाद्व्याप्तिन्या-याश्रयः स्यात्। न लोकाव्ययेत्यव्ययत्वाल्लोकादीनां सिद्धे षष्ठीनिषेधे पुनस्तेषामुपादानमव्ययसंज्ञाया एवाभावं ज्ञापयेत्। निपातसंज्ञा तु स्यादेव। ततश्चिकीर्ष्वर्थमित्यादौ निपात एकाजिति प्रगृह्यसंज्ञा स्यात्॥

(उद्द्योतः) प्रथमातिक्रमे इति। सकलकपिञ्जलालम्भा-सम्भवात्केषुचिदालब्धव्येषु त्रयो वाऽथ चतुरादय इति संदेहे इति भावः॥ व्याप्तिन्यायाश्रये बाधकमाह—निषेधावतारादिति। बहुषु न हिंस्यादिति निषेधबाधकल्पनाभिया प्रथमातिक्रमन्यायस्यैव तत्राङ्गीकार इति भावः॥ पर्यग्निकृतानारण्यानुत्सृजन्तीत्युक्ते-र्हिंसाप्रसक्त्यभावादात्रैव युक्तिरिति बोध्यम्॥ ननु न लोकेतिसूत्रे लोकादिग्रहणमिह व्याप्तिन्यायबाधकं स्यादत आह—न लोकेति। एवं चात्र रेफोच्चारणमेव ज्ञापकमत्र शास्त्रे प्रथमातिक्रमन्यायाना-श्रयणस्येति बोध्यम्॥ अत एव णिजां त्रयाणामित्यादौ त्रयाणां ग्रहणं चरितार्थम्॥

(प्राग्ग्रहणप्रयोजनाधिकरणम्)

(आक्षेपभाष्यम्)

अथ प्राग्वचनं किमर्थम्?॥

(प्रदीपः) अथेति। प्राग्ग्रहणद्वारेणावधिनिर्देशश्चोद्यते। निपाता इत्येवास्तु यथा प्रत्यय इत्यादिरधिकारो विनाप्यव-धिनिर्देशेनाभिमतविषये प्रवर्तते तथायमपि प्रवर्तिष्यते इति भावः॥

(उद्द्योतः) ननु प्राग्ग्रहणाभावे परशब्दोप्यध्याह्रियेतेत्यत आह—प्राग्ग्रहणेति॥

(११३४ समाधानवार्तिकम्॥ ५॥)

॥ * ॥ प्राग्वचनं संज्ञाऽनिवृत्त्यर्थम् ॥ * ॥

(भाष्यम्) **प्राग्वचनं क्रियते निपातसंज्ञाया अ-निवृत्तिर्यथा स्यात्। अक्रियमाणे हि प्राग्वचने ऽनवकाशाः गत्युपसर्गकर्मप्रवचनीयसंज्ञाः निपात-संज्ञां बाधेरन्। ताः मा बाधिषतेति प्राग्वचनं क्रियते॥**

(प्रदीपः) निपातसंज्ञामिति। चादिषु प्रादिष्वप्य-क्रियायोगे विकल्पितगतिसंज्ञाविषयेषु साक्षात्प्रभृतिषु च गति-

संज्ञाभावपक्षे सावकाशा निपातसंज्ञा गत्यादिसंज्ञाभिर्बाध्येतेत्यर्थः ॥

(उद्योतः) नन्वियमपि निरवकाशेत्यत आह—चादिष्विति । चादिषु सावकाशा, अक्रियायोगे प्रादिषु सावकाशेत्यादिक्रमेणान्वयः ॥ बाध्येतेति । तत्तद्विशेषसंज्ञाविषये अस्या अनुपस्थितिरेव स्यादिति भावः ॥

(आक्षेपभाष्यम्)

अथ क्रियमाणेपि प्राग्वचने यावताऽनवकाशा एताः संज्ञाः कस्मादेव न बाधन्त इति ॥

(उद्योतः) भाष्ये—अथ क्रियमाणेपीति । प्राग्रीश्वरादित्युक्तावपि विशेषसंज्ञाऽविषय एवोपस्थितिः स्यादित्यर्थः ॥

(समाधानभाष्यम्)

क्रियमाणे हि प्राग्वचने सत्यां निपातसंज्ञायामेता अवयवसंज्ञा आरभ्यन्ते तत्र वचनात्समावेशो भविष्यति ॥ प्राग्रीश्वरात् ॥ ५६ ॥

(प्रदीपः) क्रियमाण इति । रीश्वरादिति पञ्चम्या प्राक्शब्दाध्याहारे लब्धे पुनःश्रुति प्राग्ग्रहणं संपद्यते ॥ परशब्दाध्याहारेण तु पञ्चमी न भविष्यति । चादयोऽसत्त्वे इत्यादीनामसंबद्धत्वप्रसङ्गात् । तन्त्रेणैव वा द्वौ प्राक्शब्दावुच्चार्येते । तेनायमर्थः—प्राग्रीश्वराद्ये व्यवस्थितास्ते प्राङ्निपातसंज्ञा भवन्तीति निपाताः सन्तो गत्यादिसंज्ञा इति समावेशः सिद्धः । केवले तु निपाता इत्यधिकारे क्रियमाणे सत्यामपि प्रतियोगमनुवृत्तावेकसंज्ञाधिकारात्पर्यायः स्यान्न तु समावेशः ॥ अवयवसंज्ञा इति । विशिष्टावधिपरिच्छिन्नस्य समुदायस्यान्तरालपतिता गत्यादिसंज्ञाभाजोऽवयवा भवन्ति तेषां संज्ञा इत्यर्थः ॥ ५६ ॥

(उद्योतः) समाधत्ते—क्रियमाणे हीति । अवधिनिर्देशसामर्थ्यात्प्रतिसूत्रमुपस्थितौ तत्सामर्थ्यात् समावेश इति भावः ॥ नन्वेवमपि पर्यायः स्यादत आह—रीश्वरादिति ॥ असंबद्धत्वेति । विधेयानिर्देशादिति भावः ॥ निपाताः सन्त इति । प्राग्ग्रहणसामर्थ्यादेतदर्थलाभस्तेन गत्यादिसंज्ञानां निमित्तमेव निपातसंज्ञेति समावेशसिद्धिरिति भावः ॥ विशिष्टावधीति । रीश्वररूपावधिपरिच्छिन्नसमुदायस्येत्यर्थः ॥ अवयवसंज्ञा इति । षष्ठीतत्पुरुष इति भावः ॥ ५६ ॥

(१९७ निपातसंज्ञासूत्रम् ॥ १ । ४ । ४ आ. २ सू.)

२९७ चादयोऽसत्त्वे ॥ ५७ ॥

(सत्त्वशब्दार्थनिर्णयाधिकरणम्)

(आक्षेपभाष्यम्)

अयं सत्त्वशब्दः—अस्त्येव द्रव्यपदार्थकः । तद्यथा—सत्त्वमयं ब्राह्मणः सत्त्वमियं ब्राह्मणीति । अस्ति क्रियापदार्थकः सद्भावः सत्त्वमिति । कस्येदं ग्रहणम् ? ॥

(प्रदीपः) चादयोऽसत्त्वे ॥ ५७ ॥ अयमिति । अर्थद्वयेपि सत्त्वशब्दस्य प्रयोगदर्शनाद्विशेषावगतौ प्रमाणानुपलम्भात्प्रश्नः । तत्र सीदन्त्यस्मिञ्जातिगुणक्रिया इति सत्त्वं द्रव्यमुच्यते । यदा तु सतो भावः सत्त्वमिति तदा साध्यमानतया क्रियारूपापन्ना सत्ता सत्त्वशब्देनोच्यते ॥

(उद्योतः) चादयोऽसत्त्वे ॥ ५७ ॥ सीदन्त्यस्मिन्निति । विशेषणत्वेनावतिष्ठन्तेऽस्मिन्नित्यर्थः । सदेरौणादिकस्त्वः ॥ साध्यमानेनेति । वस्तुतः साध्यमानावस्थः क्रियारूपापन्नो योऽर्थः सत्तारूपः स सत्त्वपदेनोच्यत इत्यर्थः ॥

(समाधानभाष्यम्)

द्रव्यपदार्थकस्य ॥ कुत एतत् ? । एवं च कृत्वा विधिः सिद्धो भवति, प्रतिषेधश्च ॥

(प्रदीपः) एवं च कृत्वेति । यदि सत्त्वशब्देन सत्तोच्येत तदा प्रतिषेधोऽनर्थकः स्यात् । नहि चादिषु सत्तावाची कश्चिच्छब्दोस्ति यदर्थो निषेधः स्यात् । पशुर्वै पुरुष इत्यत्र च निपातसंज्ञा स्यात् । चाद्यनुकरणानां चः पठितो हिर्यस्मादर्थ इत्यादावपि विधिनिषेधौ यथाभिमतविषयं न व्यवतिष्ठेयाताम् । द्रव्यग्रहणे तु व्यवतिष्ठेते । द्रव्यशब्देन चात्र सिद्धरूपं वस्त्वभिधीयते । तदुक्तम्—

वस्तूपलक्षणं यत्र सर्वनाम प्रयुज्यते ।
द्रव्यमित्युच्यते सोऽर्थो भेद्यत्वेन विवक्षितः ॥

इति ॥

(उद्योतः) चाद्यनुकरणार्थानामिति पाठे चादीनामनुकरणं स्वरूपबोधनमर्थः प्रयोजनं येषां तेषामित्यर्थः ॥ इत्यादावपीति । निपातसंज्ञा स्यादित्यनुषज्यते ॥ विधिनिषेधाविति । असतीति हेतोरित्यादिः ॥ यथाभिमतविषयमिति । अनुकार्ये निपातत्वं नानुकरणे, नापि गवादिपरपश्वादावित्यादीति भावः ॥ सिद्धरूपमिति । तत्त्वं च लिङ्गसंख्याकारकान्वयित्वेन सर्वनामपरामर्शयोग्यत्वेन वा । तदाह—वस्तूपेति ॥ लक्षणान्तरमाह—भेद्यत्वेनेति । लिङ्गसंख्याविशेष्यत्वेनेत्यर्थः ॥

(असत्त्वेइत्यत्रप्रसज्यप्रतिषेधाधिकरणम्)

(एकदेशिभाष्ये आक्षेपभाष्यम्)

किं पुनरयं पर्युदासः—यदन्यत्सत्त्ववचनादिति, आहोस्वित्प्रसज्यायं प्रतिषेधः—सत्त्ववचने नेति ? ॥

(प्रदीपः) किं पुनरिति । उभयथा शास्त्रे दर्शनात्प्रश्नः ॥

(उद्योतः) उभयथेति । द्रव्यभिन्नेर्थे वर्तमानाश्चादय इति पर्युदासेऽर्थः । सत्त्वे वर्तमानं चादिस्वरूपं न निपातसंज्ञमिति प्रसज्यप्रतिषेधेऽर्थः ॥

(विशेषप्रश्नभाष्यम्)

किं चातः? ॥

(पर्युदासदूषकभाष्यम्)

यदि पर्युदासः विप्र इत्यत्रापि प्राप्नोति । क्रियाद्रव्यवचनोयं संघातः । द्रव्यादन्यश्च विधिनाश्रीयते । अस्ति च प्रादिभिः सामान्यमिति कृत्वा तदन्तविधिना निपातसंज्ञा प्राप्नोति ॥

(प्रदीपः) **विप्र इति ।** विप्रातीति विप्रः **आतश्चोपसर्गे** इति कप्रत्ययान्तः । क्रियोपसर्जनद्रव्यवाचित्वात् केवलाद् द्रव्यात् क्रियाद्रव्यसमुदायस्यान्यत्वाद्द्रव्यादन्यस्मिन्नर्थे वर्तते ॥ **प्रादिभिरिति ।** निपातत्वेनाभिमतैः ॥ **सामान्यमिति ।** सारूप्यम् ॥ **तदन्तविधिनेति ॥** ननु विशेष्यासन्निधानात्कथं तदन्तविधिः । एवं तर्ह्ययमर्थः—निपातस्य संज्ञा निपातसंज्ञा सा चाव्ययसंज्ञा । तस्यां चास्ति तदन्तविधिः ***प्रयोजनं सर्वनामाऽव्ययसंज्ञायाम्*** इति । तत्र विप्रशब्दे प्रशब्दस्य निपातसंज्ञायां सत्यां यथा परमोच्चैरिति स्वराद्यन्तस्याव्ययसंज्ञा भवति, एवं निपातान्तस्यापि स्यात् । ततो लुक् प्रसज्येत । विप्रकम्बल इत्यत्र च निपातान्तस्य पूर्वपदप्रकृतिस्वरः स्यात् ॥ ५७ ॥

(उद्योतः) चादिष्वपाठात्कथं प्राप्तिरित्यतो भाष्ये—**अस्ति च प्रादिभिरिति ॥ निपातत्वेनेति ।** एवं चोत्तरसूत्रविषयेऽयं दोष इत्यर्थः ॥ तथापि समुदाये कथं प्राप्तिरतो भाष्ये—**तदन्तविधिनेति ॥ निपातस्य संज्ञेति ।** सकलनिपातमुद्दिश्यैकवाक्यविहिता संज्ञेत्यर्थः ॥ प्रगृह्यसंज्ञा तु न तन्मात्रोद्देशेन विहितेति भावेनाह—**सा चाव्ययेति ॥ तस्यां चास्तीति ।** प्रयोजनमित्यादेर्गमकाच्छब्दरूपं विशेष्यमादाय तदन्तविधिरिति भावः ॥ अत्रेदं बोध्यम्—एवं हि पशुशब्दस्य जातिविशिष्टद्रव्यवाचिनोप्यसत्त्वभूतार्थत्वादसत्त्व इत्यस्य व्यावर्त्याप्रसिद्धिरतस्तात्किं पुनरित्यादिभाष्यमेकदेशिनोक्तिरित्याहुः ॥ ५७ ॥

(प्रसज्यप्रतिषेधभाष्यम्)

अथ प्रसज्यप्रतिषेधः । न दोषो भवति ॥

(सिद्धान्तिभाष्यम्)

यथा न दोषस्तथास्तु ॥ चादयोसत्त्वे ॥ ५७ ॥

(१९८ उपसर्गसंज्ञासूत्रम् ॥ १ । ४ । ७ आ० ३ सू०)

२९८ प्रादय उपसर्गाः क्रियायोगे ॥ १ । ४ । ५८ ॥

(योगविभागावश्यकताधिकरणम्)

(११३५ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ प्रादय इति योगविभागः [निपातसंज्ञार्थः, एकयोगे हि निपातसंज्ञाभावः] ॥ * ॥

(भाष्यम्) **"प्रादयः" इति योगविभागः कर्तव्यः। प्रादयोऽसत्त्ववचना निपातसंज्ञा भवन्ति । तत "उपसर्गाः क्रियायोगे" इति ॥ किमर्थो योगविभागः? । निपातसंज्ञार्थः । निपातसंज्ञा यथा स्यात् ॥ एकयोगे हि निपातसंज्ञाभावः । एकयोगे हि सति निपातसंज्ञाया अभावः स्यात् । यस्मिन्नेव विशेषे गत्युपसर्गकर्मप्रवचनीयसंज्ञास्तस्मिन्नेव विशेषे निपातसंज्ञा स्यात् ॥**

(प्रदीपः) **प्रादयः ॥ ५८ ॥** यदा प्रागेव **"प्रादयः"** इति योगो विभज्यते तदा प्रयोजनकथनाय वार्तिकम् । यदा तु **"प्रादय उपसर्गाः क्रियायोगे"** इत्येको योगः पठ्यते तदा योगविभागः कर्तव्यत्वेन चोद्यते ॥ **एकयोगे हीति ।** अक्रियायोगे निपातसंज्ञा न स्यात् । क्रियायोग एव तु गत्युपसर्गसंज्ञावत्स्यात् । ततश्च प्रगत आचार्यः प्राचार्य इत्यत्र पूर्वपदप्रकृतिस्वरो न स्यात् ॥ **यस्मिन्नेवेति । कर्मप्रवचनीय**संज्ञा **सुः पूजायामित्यादिभिर्योगैः** प्रादीनां विहिता ॥

(उद्योतः) **प्रादय उपसर्गाः ॥ ५८ ॥** ननु विभक्तस्यैव पाठात् कर्तव्य इत्यनुपपन्नमत आह—**यदेति ॥ प्रागेवेति ।** सूत्रकृता सूत्रप्रणयनकाले एवेत्यर्थः । एवं व्याख्याने भाष्यस्थकर्तव्यपदस्वारस्यभङ्गः ॥ ननु **निपाता** इत्यस्याधिकारादेकयोगेपि निपातत्वं सिद्धमत आह—**अक्रियेति ॥** तदाह—भाष्ये—**यस्मिन्नेव विशेष इति ।** क्रियायोगरूपे इत्यर्थः ॥ ननु प्रादयः क्रियायोगे उपसर्गा गतय इतिवत् प्रादयः कर्मप्रवचनीया इति वचनाभावादाह—**सुः पूजायामिति ॥**

(न्यूनतापूरणाधिकरणम्)

(११३६ आक्षेपवार्तिकम् ॥ २ ॥)

॥ * ॥ अकुच्छन्दस्योपसंख्यानम् ॥ * ॥

(भाष्यम्) **अकुच्छन्दस्योपसंख्यानं कर्तव्यम् ।**

मरुद्दत्तो मरुत्तः "अच उपसर्गात्" इति तत्वं यथा स्यात् ॥

(प्रदीपः) मरुद्दत्त इति। प्रक्रियायां रूपमलौकिकमिदमुपात्तम्। तत्वेन हि नित्यं भाव्यम्। उपसर्गसंज्ञैव चास्येष्यते न निपातसंज्ञा। तस्यां हि सत्यां निपाता आद्युदात्ता इत्याद्युदात्तत्वं तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरेण स्यात्। अन्तोदात्तश्च मरुच्छब्द इष्यते। अव्ययसंज्ञा च स्यात्। तस्त्र एवोपसर्गसंज्ञेष्यते। अनभिधानाद्धि किरश्च न भवति। संज्ञावचनसामर्थ्याच्चानजन्तत्वेपि तत्वं प्रवर्तते। अनेन तु न्यायेन मरुन्नयतीति तवर्गव्यवायेपि णत्वं प्राप्नोति। तस्मात्तत्व एवोपसर्गसंज्ञा वक्तव्या॥ प्रकारान्तरेणापि मरुत्तशब्दो व्युत्पादयिष्यते तप्पर्वमरुद्भ्यामिति॥

(उद्द्योतः) नन्वच उपसर्गादित्यत्र त्त इति द्वितकारकनिर्देशात्सर्वादेशस्तत्वमनजन्तत्वेपि संज्ञाविधानसामर्थ्याद्भवति। तच्च नित्यमिति मरुद्दत्त इत्ययुक्तमत आह—प्रक्रियायामिति॥ नन्वलौकिकप्रक्रियावाक्यं मरुत्‌दात इति दर्शयितुमुचितं न तु दत्त इतीति चेदत्राहुः—मरुद्भिर्दत्त इत्यर्थकलुप्तविभक्तिकमरुच्छब्देन श्रुतौ मरुत्तशब्दस्य विग्रहप्रदर्शनं कृतं तथैव भगवतोक्तमिति॥ इष्यत इति। तृतीयाकर्मणीतिपूर्वपदप्रकृतिस्वरेणेत्यर्थः। भृमोरुतिप्रत्ययान्तत्वादन्तोदात्तः सः। एवं च मरुत्तपदं मध्योदात्तमिति भावः॥ अव्ययसंज्ञा च स्यादिति। तथा च मरुद्भिर्दत्त इति मत्वर्थीयप्रकरणस्थभाष्यप्रयोगे विभक्तिश्रवणं न स्यादिति भावः॥ नन्वस्योपसर्गत्वे उपसर्गे घोः किरातश्चोपसर्गे इति अङ्की स्यातामत आह—अनभिधानादिति॥ अनेन न्यायेन संज्ञावचनसामर्थ्यरूपेण॥ तस्मात्तत्व एवेति। अत एवोपसर्गाश्चाभिवर्जमित्याद्युदात्तत्वमपि न॥ नन्वेवं तत्वविधावेव मरुत्त उप[संख्यानेन सिद्धे संज्ञाविधावुप]संख्यानं व्यर्थं स्यादिति चिन्त्यम्॥ केचित्त्वत्रोपसंख्यानेन निपातत्वमिष्यते एव। तेनाद्युदात्त एव मरुत्‌शब्दः। निपातसंज्ञापि तत्वविषये एवेति मरुद्भिर्दत्त इति पाञ्चमिकभाष्यप्रयोगस्य नानुपपत्तिः। पक्षेपि तप् पर्वमरुद्भ्यामिति निर्देव पाठ इत्याहुः॥ कैयटस्वारस्येन तु स पिदिति बोध्यम्॥ व्युत्पादयिष्यत इति। मत्वर्थीयप्रकरणे इति शेषः॥५८

(११२७ आक्षेपवार्तिकम्॥ २॥)

॥ * ॥ श्रच्छन्दस्योपसंख्यानम् ॥ * ॥

(भाष्यम्) श्रच्छब्दस्योपसंख्यानं कर्तव्यम्। श्रद्धा॥ प्रादय उपसर्गाः॥ ५८॥

(प्रदीपः) श्रच्छब्दस्येति। तेन भिदादिषु श्रद्धाशब्दो न पठितव्यो भवति॥ ५८॥

(१९९ गतिसंज्ञासूत्रम्॥ १।४।४ आ. ४ सू.)

२९९ गतिश्च॥ १। ४। ५९॥

(न्यूनतापूर्त्यधिकरणम्)

(११२८ आक्षेपवार्तिकम्॥ १॥)

॥ * ॥ कारिकाशब्दस्य ॥ * ॥

(भाष्यम्) कारिकाशब्दस्योपसंख्यानं कर्तव्यम्। कारिकाकृत्य॥

(प्रदीपः) गतिश्च॥ ५९॥ कारिकाशब्दस्येति। कारिका क्रिया मर्यादा स्थितिरित्यर्थः। यत्न इत्यपरे। यस्तु श्लोकवाची कारिकाशब्दस्तस्य ग्रहणं न भवति। क्रियायोगग्रहणेन कारिकाशब्दस्य विशेषणात्क्रियावृत्तेर्ग्रहणात्॥

(उद्द्योतः) गतिश्च॥ ५९॥ कारिकेति। भावे ण्वुल्। श्लोकादौ तु कारके॥ श्लोकवाचीति। दासीवाचिनोप्युपलक्षणम्। क्रियायोगेति। क्रियारूपे युज्यमाने वर्तमानादित्यर्थः॥

(११२९ आक्षेपवार्तिकम्॥ २॥)

॥ * ॥ पुनश्चनसौ छन्दसि ॥ * ॥

(भाष्यम्) पुनश्चनसौ छन्दसि गतिसंज्ञौ भवत इति वक्तव्यम्। पुनरुत्स्यूतं वासो देयम्। पुनर्निष्कृतो रथः। उशिग्दूतश्चनोहित इति॥

(प्रदीपः) पुनश्चनसाविति। ततश्च पुनराधेयमित्यत्र कृदन्तोत्तरपदप्रकृतिस्वरेण यतो नाव इति धेशब्द उदात्तः॥ पुनरुत्स्यूतमिति। गतित्वात्समासः। स्वरस्तु प्रवृद्धादेराकृतिगणत्वादन्तोदात्तत्वम्॥ चनोहित इति। निपातत्वादाद्युदात्तस्य चनःशब्दस्य गतिरनन्तर इति प्रकृतिस्वरः॥

(उद्द्योतः) पुनःशब्दस्य गतित्वे स्वयं फलं दर्शयति—ततश्चेति। एतेन पुनरुत्स्यूतमिति भाष्योदाहरणे सुप् सुपेति समासेनैव सिद्धे पुनःशब्दस्य गतिसंज्ञा व्यर्थेत्यपास्तम्। तद् ध्वनयन्वक्ष्यति—स्वरस्त्विति। सह सुपेतिसूत्रे भाष्ये त्वसमस्तत्वाभिप्रायेण गतिर्गताविति निघात इत्युक्तम्॥

(क्रियाविशेषावधारणाधिकरणम्)

(११४० आक्षेपवार्तिकम्॥ ३॥)

॥ * ॥ गत्युपसर्गसंज्ञाः क्रियायोगे यत्क्रियायुक्तास्तं प्रतीति वचनम् ॥ * ॥

(भाष्यम्) गत्युपसर्गसंज्ञाः क्रियायोगे यत्क्रियायुक्तास्तं प्रति गत्युपसर्गसंज्ञा भवन्तीति वक्तव्यम्॥

(प्रदीपः) गत्युपसर्गसंज्ञा इति । क्रियायोग इति सामान्येनोपादानाद्विशेषावधारणार्थं वचनम् । अथ वा प्रत्यासत्त्यैव क्रिया गृह्यते इति न्यायव्युत्पादनार्थम् ॥

(प्रयोजनप्रश्नभाष्यम्)

किं प्रयोजनम् ? ॥

(११४१ प्रयोजनवार्तिकम् ॥ ४ ॥)

॥ * ॥ प्रयोजनं घञ् षत्वणत्वे ॥ * ॥

(भाष्यम्) घञ् [प्रयोजयति] प्रवृद्धो—भावः प्रभावः "अनुपसर्गे" इति प्रतिषेधो मा भूत् ॥

[षत्वणत्वे च प्रयोजयतः] षत्वम्—विगताः सेचका अस्माद्ग्रामाद्विसेचको ग्रामः "उपसर्गाद्—" इति षत्वं मा भूत् ॥ णत्वम्—प्रगता नायका अस्माद्ग्रामात्प्रनायको ग्रामः "उपसर्गाद्—" इति णत्वं मा भूत् ॥

(११४२ लाघववार्तिकम् ॥ ५ ॥)

॥ * ॥ वृद्धिविधौ च धातुग्रहणानर्थक्यम् ॥ * ॥

(भाष्यम्) वृद्धिविधौ च धातुग्रहणमनर्थकम्—"उपसर्गादृति धातौ" इति । तत्र धातुग्रहणस्यैतत्प्रयोजनमिह मा भूत्—प्रर्षभं वनमिति ॥ क्रियमाणे चापि धातुग्रहणे प्रर्छक इत्यत्र प्राप्नोति । यत्क्रियायुक्तास्तं प्रतीति वचनान्न भवति ॥

(प्रदीपः) वृद्धिविधौ चेति । उपसर्गेणैव धातोराक्षेपात् ॥ प्रर्छक इति । प्रगता ऋच्छका अस्मादिति बहुव्रीहिः । तत्र धातुग्रहणस्य शाकलनिवृत्तिः प्रयोजनं वक्ष्यते ॥

(उद्द्योतः) शाकलनिवृत्तिः प्रयोजनमिति ॥ शाकलम् ऋत्यक इति । योगविभागेन पुनर्विधानद्वारेति भावः ॥

(११४३ दूषणवार्तिकम् ॥ ६ ॥)

[॥ * ॥ वद्धिधिनस्भावावीत्त्वस्वाङ्गादिस्वरणत्वेषु दोषः ॥ * ॥]

(भाष्यम्) वद्धिधिनस्भावावीत्त्वस्वाङ्गादिस्वरणत्वेषु दोषो भवति । वद्धिधि—यदुद्वतो निवतो यासि वप्सन् । वद्धिधिः ॥ नस्भाव—प्रणसं मुखम् । उन्नसं मुखम् । नस्भाव ॥ अवीत्त्व—प्रेपं परेपम् । अवीत्व ॥ स्वाङ्गादिस्वर—प्रस्फिक् प्रोदरः । स्वाङ्गादिस्वर ॥ णत्व—'प्र णः शूद्रः' 'प्र ण आचार्यः' 'प्र णो राजा' 'प्र णो वृत्रहा' । उपसर्गादित्येते विधयो न प्राप्नुवन्ति ॥

(प्रदीपः) उद्वत इति । क्रियाशब्दस्याप्रयोगादुपसर्गत्वाभावः ॥

(उद्द्योतः) उपसर्गाच्छन्दसि धात्वर्थे इति वतिः । अञ् नासिकाया इति वर्तमाने उपसर्गाच्चेत्यच् नस्भावौ । अप्स्वन्तरुपसर्गेभ्योप ईद् । उपसर्गात्स्वाङ्गमित्युत्तरपदाद्युदात्तत्वरूपः स्वरः । उपसर्गाद्बहुलमिति णत्वम् ॥ ननु धात्वर्थे वतेर्विधानादस्त्येव क्रियायोगोऽत आह—क्रियाशब्दस्येति । धात्वर्थे वर्तमानात् स्वार्थे स इति भावः ॥ प्रत्ययार्थत्वेपि तद्दशायां तस्य क्रियात्वाभाव इत्यन्ये ॥ उद्वत इत्यादेरुद्गतान् निगतान् इत्यर्थः । प्रेपमित्यादेः प्रगता आपो यस्मिन्नित्यादिरर्थः । प्रण इत्यादेः प्रकृष्टानामस्माकमित्यर्थः ॥

(११४४ दूषणपरिहारवार्तिकम् ॥ ७ ॥)

॥ * ॥ वद्धिधिनस्भावावीत्त्वस्वाङ्गादिस्वरणत्वेषु वचनप्रामाण्यात्सिद्धम् ॥ * ॥

(भाष्यम्) अनवकाशा एते विधयस्ते वचनप्रामाण्याद्भविष्यन्ति ॥

(प्रदीपः) अनवकाशा इति । येषां हि क्रियाशब्दप्रयोगे तं प्रत्युपसर्गसंज्ञा ते संप्रत्यनुपसर्गसंज्ञा अपि गृह्यन्त इत्यर्थः ॥

(उद्द्योतः) इत्यर्थ इति । तत्र सर्वत्रोपसर्गग्रहणं प्रायुपलक्षणमिति भावः ॥

(११४५ आक्षेपवार्तिकम् ॥ ८ ॥)

॥ * ॥ सुदुरोः प्रतिषेधो नुम्विधितत्वषत्वणत्वेषु ॥ * ॥

(भाष्यम्) सुदुरोः प्रतिषेधो नुम्विधितत्वषत्वणत्वेषु वक्तव्यः । नुम्विधि—सुलभं दुर्लभम् । "उपसर्गाद्—" इति नुम्मा भूदिति । "न सुदुर्भ्यां केवलाभ्याम्" इत्येतन्न वक्तव्यं भवति ॥

(प्रयोजनपरिहारभाष्यम्)

नैतदस्ति प्रयोजनम् । क्रियत एतन्न्यास एव ॥

(प्रदीपः) क्रियत इति । केवलाभ्यामिति विशेषणाभिधानार्थमवश्यं कर्तव्यम् । तेनातिसुलभमित्यत्रोपसर्गत्वे नुम् भवत्येव ॥

(उद्द्योतः) ननु लघुना गुरोः प्रत्याख्यानं क्रियते एवेत्यसंगतमत आह—केवलाभ्यामितीति ॥ अवश्यमिति । वार्तिककृतापीति भावः ॥ इत्यत्रोपसर्गत्वे नुम् भवत्येवेति । सोरुप-

सर्गत्वे सतीत्यर्थः ॥ निषेधाभावादित्याशयः ॥ इत्यतेरुपसर्गत्वे इति पाठेऽतेः परस्य सोरुपसर्गत्वं इत्यर्थः ॥ इत्यतेः परस्योरुपसर्गत्वे इति पाठस्तु युक्त एव ॥

(उदाहरणसमन्वयभाष्यम्)

तत्व—सुदत्तम् "अच उपसर्गात्तः" इति तत्वं मा भूदिति ॥ षत्व—सुसिक्तं घटशतेन । सुस्तुतं श्लोकशतेन। "उपसर्गाद्" इति षत्वं मा भूदिति ॥ "सुः पूजायाम्" इत्येतन्न वक्तव्यं भवति ॥

(उद्द्योतः) सुः पूजायामित्येतत्कर्मप्रवचनीयसंज्ञाविधायकम् ॥

(प्रयोजनपरिहारभाष्यम्)

नैतदस्ति प्रयोजनम् । क्रियत एतन्न्यास एव ॥

(प्रदीपः) क्रियत इति । पूजायामिति विशेषणोपादानार्थम् । तेन सुषिक्तं किं तवात्रेत्यादौ षत्वं भवत्येव ॥ ५९

(उदाहरणसमन्वयभाष्यम्)

णत्व—दुर्नयं दुर्नीतमिति । "उपसर्गाद्" इति णत्वं मा भूदिति ॥ गतिश्च ॥ ५९ ॥

(उद्द्योतः) भाष्ये—णत्वं मा भूदिति । न च दुसमादाय णत्वं दुर्वारम्, कृतरोर्दुसोप्यत्रानुकरणेन तस्यापि निषेधात् ॥ ५९ ॥

(२०० गतिसंज्ञासूत्रम् ॥ १ । ४ । ४ आ. ५ सू.)

३०० ऊर्यादिच्विडाचश्च ॥ ६० ॥

(उद्द्योतः) ऊर्यादि ॥ ६० ॥ च्विडाचोः केवलयोः प्रत्ययोः क्रियायोगासंभवात्सामर्थ्येन संज्ञाविधावपि तदन्तविधिः ॥

(अनिष्टपरिहाराधिकरणम्)

(११४९ आक्षेपवार्तिकम् ॥ १ ॥)

[॥ * ॥ कृभ्वस्तियोगे ॥ * ॥]

(भाष्यम्) **कृभ्वस्तियोग इति वक्तव्यम् । इहैव यथा स्यात्—ऊरीकृत्य ऊरीभूय । इह मा भूत्—ऊरी पक्त्वा ॥**

(प्रदीपः) **ऊर्यादि ॥ ६० ॥ ऊरीपक्त्वेति ।** प्रयोगापर्यालोचनेन संभवमात्राश्रयेणैतदुदाहृतम् ॥

(उद्द्योतः) वक्ष्यमाणरीत्यास्य प्रयोगस्यैवाभावादाह—**प्रयोगेति** ॥ ६० ॥

(तृतीयाक्षेपभाष्यम्)

तत्तर्हि वक्तव्यम्? ॥

(सिद्धान्तिसमाधानभाष्यम्)

न वक्तव्यम् । क्रियायोग इत्यनुवर्तते । न चान्यया क्रिययोर्यादिच्विडाचां योगोस्ति ॥ ऊर्यादिच्वि० ॥ ६० ॥

(प्रदीपः) **न चान्ययेति ।** च्विडाचौ तावत् कृभ्वस्तियोग एव विहितौ । ऊर्यादयोपि कृभ्वस्तिविषया एव प्रयुज्यन्ते नान्यत्र ॥ ६० ॥

(२०१ गतिसंज्ञासूत्रम् ॥ १ । ४ । ४ आ. ६ सू.)

३०१ अनुकरणं चानितिपरम् ॥ १ । ४ । ६१ ॥

(समासनिर्णयाधिकरणम्)

(आक्षेपभाष्यम्)

कथमिदं विज्ञायते—इतेः परमितिपरं न इतिपरमनितिपरमिति। आहो स्विदितिः परो यस्मात्तदिदमितिपरं न इतिपरमनितिपरमिति ॥

(प्रदीपः) **अनुक ॥ ६१ ॥ कथमिति ।** द्वयोरपि समासयोः संभवाद्दोषदर्शनाच्च प्रश्नः ॥

(उद्द्योतः) **अनुकरणं ॥ ६१ ॥ इतेः परमिति । सुप्सु**पेति योगविभागात्समासः ॥

(विशेषप्रश्नभाष्यम्)

किं चातः? ।

(प्रथमपक्षदूषकभाष्यम्)

यदि विज्ञायते—इतेः परमितिपरं न इतिपरमनितिपरमिति, खाडितिकृत्वा निरष्ठीवदित्यत्र प्राप्नोति ॥

(प्रदीपः) **खाडिति कृत्वेति ।** गतिसंज्ञायां समासः स्यात् । धातोश्चानन्तरं प्रयोग इति रूपमेतन्न सिध्येत् । इति खाट्कृत्येत्यत्र च निषेधप्रसङ्गः ॥

(उद्द्योतः) **धातोश्चानन्तरमिति ।** तदव्यवधानेन गतेः प्रयोग इत्यर्थः ॥ **इति खाट्कृत्येति ।** इति हेतोः खाट्कृत्य गत इत्यर्थः ॥

(द्वितीयपक्षदूषकभाष्यम्)

अथ विज्ञायते—इतिः परो यस्मात्तदितिपरं न इतिपरमनितिपरमिति, श्रौषड्वौषडिति कृत्वा निरष्ठीवदित्यत्र प्राप्नोति ॥

(प्रदीपः) **श्रौषडिति ।** श्रौषट्शब्द इतिपरो न भवति वौषटा व्यवधानादिति गतिसंज्ञाप्रसङ्गः ॥ ननु व्यवहितेपि परशब्दस्य दर्शनाद्भवत्येवेतिपरत्वम् । नैष दोषः । अव्यवधान एवास्य मुख्या वृत्तिः । अन्यत्र त्वन्तरालस्थमसमीक्ष्याव्यवधानमेवाश्रित्य प्रयुज्यते । इह तु वौषटो व्यवधायकस्योच्चारणादयुक्तमनपेक्षणम् । खाट्कृत्येति निरष्ठीवदित्यत्र धातुव्यवधानेपि प्रतिषेधप्रसङ्गात् ॥

(उद्द्योतः) नन्वितेः परत्वसत्त्वेन कथमत्र प्राप्तिरत आह—**श्रौषडिति ।** एवं गतिसमासस्य नित्यत्वादयं प्रयोगो न स्यादिति

भावः ॥ तस्मिन्निति सूत्रे निर्दिष्टग्रहणाद् व्यवहितसाधारण एवाय-मित्यतो दूषणान्तरमाह—खादकृत्वेतीति । इति हेतोः खाद्कृत्य निरष्ठीवदित्यर्थः । वस्तुत इतेः परमिति विग्रहवाक्ये उत्तराङ्गविकल-तस्मादितिपरिभाषोपस्थित्याऽव्यवहितपरत्वबोधादुक्तावपि तदन्तर्भा-वेनैकार्थीभाव इति भाष्याशयः ॥

(समाधानभाष्यम्)

अस्तु तावद्—इतिः परो यस्मात्तदितिपरं न इति परमनितिपरमिति ॥

(आक्षेपस्मारणभाष्यम्)

ननु चोक्तम्—श्रौषड्वौषडिति कृत्वा निरष्ठीव-दित्यत्र प्राप्नोतीति ॥

(आक्षेपपरिहारभाष्यम्)

नैष दोषः । इदं तावदयं प्रष्टव्यः—अथेह "ते प्राग्धातोः" इति कथं गतिमात्रस्य पूर्वप्रयोगो भ-वति—उपोद्धरतीति ? ॥

(प्रदीपः) इदं तावदिति । यो व्यक्त्याश्रयेण व्यव-धानं मन्यते ॥

(उद्द्योतः) अयंपदार्थं दर्शयति—य इति ॥

(तद्द्येोत्तरभाष्यम्)

गत्याकृतिः प्रतिनिर्दिश्यते ? ॥

(प्रदीपः) गत्याकृतिरिति । तस्याश्च भिन्नास्वपि व्य-क्तिषु अभिन्नाया नास्त्यत्र व्यवधानम् ॥

(उद्द्योतः) तस्याश्चेति । गतिशब्देन तत्संज्ञकानेकव्यक्ते-र्ग्रहणं लक्ष्यानुसारादित्याशयः ॥

(तदुक्तोत्तरस्यैव समाश्रयणभाष्यम्)

इहापि तर्ह्यनुकरणाकृतिः प्रतिनिर्दिश्यते ॥

(अनितिपरपदप्रयोजनाधिकरणम्)

(आक्षेपभाष्यम्)

किमर्थमिदमुच्यते ? ॥

(प्रदीपः) किमर्थमिति । अनितिपरमित्येतदित्यर्थः । संज्ञानियमपक्षे सिद्धिं मत्वा प्रश्नः ॥

(उद्द्योतः) गतिसंज्ञार्थं सूत्रमावश्यकमिति प्रश्नानुपपत्तिरत आह—अनितिपरमित्येतदिति ॥ संज्ञेति । प्राक् प्रयुक्ता एव गत्यादिसंज्ञा इति तदर्थः ॥ ६१ ॥

(११४७ समाधानवार्तिकम् ॥ १ ॥)

॥ * ॥ अनुकरणस्येतिकरणपरत्वप्रति-षेधोऽनिष्टशब्दनिवृत्त्यर्थः ॥ * ॥

(भाष्यम्) **अनुकरणस्येतिकरणपरत्वप्रतिषेध उच्यते । किं प्रयोजनम् ? । अनिष्टशब्दनिवृत्त्यर्थः । अनिष्टशब्दता मा भूदिति । इदं विचारयिष्यते—प्राग्धातुवचनं प्रयोगनियमार्थं वा स्यात्संज्ञानियमार्थं वेति । तद्यदा प्रयोगनियमार्थं तदानिष्टशब्द-निवृत्त्यर्थमिदं वक्तव्यम् । यदा हि संज्ञानियमार्थं तदा न दोषो भवति ॥ अनुकरणम् ॥ ६१ ॥**

(प्रदीपः) अनिष्टशब्दनिवृत्त्यर्थ इति । खाडिति-कृत्वेति प्रयोक्तव्ये इति खाट्कृत्वेतिप्रयोगः स्यात् । प्रयोग-नियमे चायं दोषः । तत्र ह्ययमर्थः—गत्युपसर्गसंज्ञा धातोः प्रागेव प्रयोक्तव्या इति । ततो व्यवहितस्य प्रयोगाप्रसङ्गः ॥ संज्ञानियमे तु न दोषः । तेनैव नियमेन खाडितिकृत्वेत्यत्र व्यवहितस्य संज्ञानिवारणादस्य प्रयोगस्य सिद्धत्वात् ॥ ६१ ॥

(२०२ गतिसंज्ञासूत्रम् ॥ १ । ४ । ४ आ. ७ सू.)

३०२ आदरानादरयोः सदसती ॥ १ । ४ । ६२ ॥

(उद्द्योतः) आदरानादरयोः ॥ ६२ ॥ आदरः प्रत्यु-त्थानादिविषयस्त्वराख्यः । अनादरः परिभव औदासीन्यं च, तच्चावश्यकोत्थानादिविषयोपेक्षा ॥

(अनादरासद्ग्रहणप्रयोजनाधिकरणम्)

(आक्षेपभाष्यम्)

इदमतिबहु क्रियते—आदरे अनादरे सदसदिति । 'आदरे सत्' इत्येव सिद्धम् ॥

(प्रत्याक्षेपभाष्यम्)

कथमसत्कृत्येति ? ॥

(प्रदीपः) आदरा ॥६२॥ कथमसत्कृत्येति । यदि—न सत्कृत्यासत्कृत्येति नञ्समासः क्रियते, तदा सतिशिष्टत्वात्कृ-दुत्तरपदप्रकृतिस्वरं बाधित्वाऽव्ययपूर्वपदप्रकृतिस्वरेणाद्युदात्तत्वं स्यात् । अथ—न सदसदिति समासः क्रियते, तदा सच्छब्दस्य गतिसंज्ञाविधीयमाना ऽसच्छब्दस्य न स्यादिति भावः ॥

(प्रत्याक्षेपपरिहारभाष्यम्)

तदन्तविधिना भविष्यति ॥

(प्रदीपः) तदन्तविधिनेति । यद्यपीह प्रकृतं विशेष्यं नास्ति तथापि कार्यार्थत्वात्संज्ञायाः कार्यप्रदेशेषु प्रकृतस्य गतिना विशेषणात्तदन्तविधिर्भवति । तत्र समासविधौ सुबिति प्रकृतं **गतिरनन्तर** इत्यत्र पूर्वपदं **गतिर्गतौ** इत्यत्र पद-स्येति । अव्ययसंज्ञायामस्त्येव तदन्तविधिः ॥

(उद्द्योतः) कार्यार्थत्वादिति । तेनासच्छब्देन समासादि-सिद्धिः । गतिसंज्ञा तु सच्छब्दस्यैवेति भावः ॥ सुबिति प्रकृत-मिति । समर्थ इति प्रकृतमित्यपि बोध्यम् ॥

(प्रत्याक्षेपान्तरभाष्यम्)

केनेदानीमनादरे भविष्यति ? ॥

(उद्द्योतः) ननु तदन्तविधिना कार्यसम्भवेऽप्यनादर इत्यस्या-सत्त्वे कथमत्र तत्प्राप्तीतिरित्याह—भाष्ये केनेदानीमिति ॥

(प्रत्याक्षेपान्तरपरिहारभाष्यम्)

नञाऽऽदरप्रतिषेधं विज्ञास्यामः—न आदरेऽनादर इति ॥

(प्रदीपः) **न आदर इति ।** अनेनासच्छब्दस्यानादरार्थवृत्तितां दर्शयति । ततश्चानादरग्रहणेन यत्साध्यं तदन्यथापि सिध्यतीत्येवंपरमेतत् ॥

(उद्द्योतः) नन्वनादरइत्यस्यामत्त्वे कथं नञाऽऽदरप्रतिषेधो विज्ञास्यतेऽत आह—**अनेनेति ।** आदरप्रतिषेधम् इत्यस्य सदर्थादरप्रतिषेधम् इत्यर्थः ॥

(समाधानभाष्यम्)

नैवं शक्यम् । आदरप्रसङ्ग एव स्यादनादरप्रसङ्गे न स्यात् ॥ अनादरग्रहणे पुनः क्रियमाणे बहुव्रीहिरयं विज्ञायते—अविद्यमानादरे अनादरे इति । तस्मादनादरग्रहणं कर्तव्यम् ॥ असतस्तु तदन्तविधिना सिद्धम् ॥ आदरानादरयोः ॥ ६२ ॥

(प्रदीपः) **आदरप्रसङ्ग इति ।** गुरुमसत्कृत्येत्यादौ तु स्यात्, पाखण्डिनमसत्कृत्येत्यादौ तु न स्यात् । तथाहि—अब्राह्मण इति क्षत्रियादिरेवोच्यते न तु गोलोष्टादिः ॥ **बहुव्रीहिरिति ।** स चात्यन्ताभावेऽपि प्रसक्त्यभावे च भवतीति सर्वत्र संज्ञा सिध्यति ॥ **असतस्त्विति । आदरानादरयोः सदित्येव** वक्तव्यम् । तत्रानादरे सच्छब्दस्य वृत्त्यसंभवात्सामर्थ्यात्तदन्तविधिनाऽसच्छब्दस्य गतिसंज्ञा भविष्यति । यथा **गोष्पदं सेवितेत्यत्रासेविते** गोष्पदशब्दस्य वृत्त्यसंभवादगोष्पदार्थमसेवितग्रहणम् ॥ ६२ ॥

(उद्द्योतः) **त्यादौ तु स्यादिति ।** नञ्समासे सदृशस्यैव प्रतीतेर्गुर्वादिविषये एव प्रयोगः स्यात् । पाखण्ड्यादिविषये तु प्रयोगो न स्यादिति भावः ॥ **प्रसक्त्यभावे चेति** पाठः ॥ नन्वनादरग्रहणेऽसद्ग्रहणमपि कार्यमेव । अन्यथा सच्छब्दस्यानादरेऽवृत्तेरत्र तदन्तविध्यभावाच्च कस्य तत्र वर्तमानस्य संज्ञा स्यादत आह—**आदरेत्यादि ॥ सामर्थ्यादिति ।** प्रकृतविशेष्याभावेऽपि शब्दरूपं विशेष्यमादायेत्यर्थः ॥ ६२ ॥

(२०३ गतिसंज्ञासूत्रम् ॥ १ । ४ । ४ आ. ८ सू.)

३०४ अन्तरपरिग्रहे ॥ ६४ ॥

(११४८ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ अन्तःशब्दस्याङ्किविधिसमासणत्वेषूपसंख्यानम् ॥ * ॥

(भाष्यम्) **अन्तःशब्दस्याङ्किविधिसमासणत्वेषूपसंख्यानं कर्तव्यम् । अङ्—अन्तर्द्धा । किविधिः—अन्तर्द्धिः । समास—अन्तर्हत्य । णत्वम्—अन्तर्हण्यात् गोभ्यो गाः ॥ अन्तरपरिग्रहे ॥ ६४ ॥**

(प्रदीपः) **अन्तरप ॥ ६४ ॥ अन्तःशब्दस्येति ।** अङ्किविधिणत्वानि उपसर्गसंज्ञाश्रयाणि । समासस्तु गतिसंज्ञाश्रय इत्यपूर्ववचनं सूत्रोपादानं च सामान्येनोपसंख्यानमुच्यते । गतिसंज्ञाया अनेनैव सिद्धत्वादपूर्ववचनाभावात् ॥ **अन्तर्हण्यादिति । हन्तेरत्पूर्वस्ये**तिणत्वस्य सिद्धत्वाद् **अन्तरदेशे** इति न वक्तव्यं भवति । देशे तु क्षुभ्नादित्वाण्णत्वाभावः । **तथैवायनं चेति** न वक्तव्यम्, **कृत्यचः** इति सिद्धत्वात् । अन्तर्णयतीत्यत्राप्यु**पसर्गा**दिति णत्वं सिध्यति ॥ ६४ ॥

(उद्द्योतः) **अन्तरपरिग्रहे** ॥ ६४ ॥ ननु समासस्य सूत्रेणैव सिद्धेर्वार्तिके समासग्रहणं व्यर्थमत आह—**सामान्येनेति** । एवं चोपसंख्यानशब्देनापूर्ववचनमेव नोच्यते किं तु विधानमात्रम् । एवं चोपसर्गसंज्ञाविषयमपूर्ववचनं गतिसंज्ञाविषयमत्रं चोपसंख्यानशब्देनोच्यत इति न समासग्रहणं व्यर्थमिति भावः ॥ ननु गतिसंज्ञांशेऽप्यपूर्वत्वमस्त्यत आह—**गतिसंज्ञाया इति ॥ अनेनैवेति ।** सूत्रेणैवेत्यर्थः । तदतिरिक्तविषये त्वनेनापि नेष्यत भावः ॥ नन्वन्तरदेशे इत्यादिनैव सिद्धत्वे उपसंख्यानं व्यर्थमत आह—**हन्तेरित्यादि ॥ तथैवेति ।** अन्तरयणमित्यस्यानेनैव सिद्धेर्देशे प्रतिषेधोऽपि क्षुभ्नादित्वात्सिद्ध इति भावः ॥ तदारम्भेऽप्यस्यावश्यकतां दर्शयति—**अन्तर्णयतीति** ॥ ६४ ॥

(२०४ गतिसंज्ञासूत्रम् ॥ १ । ४ । ४ आ. ९ सू०)

३१२ साक्षात्प्रभृतीनि च ॥ १ ।४।७३॥

(न्यूनतापूर्त्यधिकरणम्)

(११४९ आक्षेपवार्तिकम् ॥ १ ॥)

॥*॥ साक्षात्प्रभृतिषु च्व्यर्थवचनम् ॥ *॥

(भाष्यम्) **साक्षात्प्रभृतिषु च्व्यर्थवचनं कर्तव्यम् । असाक्षात्साक्षात्कृत्वा साक्षात्कृत्य । यदा हि साक्षादेव सन् किंचित्क्रियते तदा मा भूदिति॥**

(प्रदीपः) **साक्षात्** ॥ ७३ ॥ **साक्षात्प्रभृतिष्विति ।** अभूततद्भावविषयाणामेव यथा स्याद् यदा तु साक्षाद्भूता रूपान्तरेण क्रियन्ते तदा मा भूदित्यर्थः ॥

(उद्द्योतः) साक्षात् ॥ ७३ ॥ **साक्षाद्भूता इति ।** प्रत्यक्षा इत्यर्थः । तदुक्तं भाष्ये—**यदा हि साक्षादेव सत् किंचित्क्रियत इति ॥**

(११५० आक्षेपवार्तिकम् ॥ २ ॥)

॥ * ॥ मकारान्तत्वं च गतिसंज्ञासंनियुक्तम् ॥ * ॥

(भाष्यम्) **मकारान्तत्वं च गतिसंज्ञासंनियोगेन वक्तव्यम् । लवणंकृत्य ॥**

(उद्योतः) लवणमित्यादिगणपाठान्मान्ता अपि एते शब्दाः स्वतन्त्रा इति भ्रमं व्यावर्तयति—भाष्ये—मकारान्तत्वं चेति ॥

(११५१ आक्षेपवार्तिकम् ॥ ३ ॥)

॥ * ॥ तत्र च च्विप्रतिषेधः ॥ * ॥

(भाष्यम्) , च च्व्यन्तस्य प्रतिषेधो वक्तव्यः। लवणी

लवणीकृत्येति । अत्र हि परत्वादनेन विभाषा प्राप्नोति । नित्या च गतिसंज्ञेष्यते ॥

(११५२ आक्षेपपरिहारवार्तिकम् ॥ ४ ॥)

॥ * ॥ नवा पूर्वेण कृतत्वात् ॥ * ॥

(भाष्यम्) नवा वक्तव्यम् । किं कारणम्?। पूर्वेण कृतत्वात् । अस्त्वनेन विभाषा, पूर्वेण नित्या भविष्यति ॥

(प्रदीपः) पूर्वेणेति । पुनःप्रसङ्गविज्ञानादिति भावः ॥

(उद्योतः) पुनःप्रसङ्गेति । परत्वाद्विकल्पेपि तदभावे नित्यविधिप्राप्त्या न दोष इति भावः ॥ न च प्राप्तविभाषाविषये वैकल्पिकाभावे नित्याङ्गीकारे विकल्पशास्त्रस्य वैयर्थ्यापत्तिः । अच्व्यन्ते चारितार्थ्यात् ॥

(प्रयोजनान्तरस्मारणभाष्यम्)

इदं तर्हि प्रयोजनम्—*मकारान्तत्वं च गतिसंज्ञासन्नियुक्तम्* इत्युक्तं तच्च च्व्यन्तस्य मा भूदिति ॥

(प्रदीपः) च्व्यन्तस्य मा भूदिति । एकदेशविकृतस्यानन्यत्वात् प्राप्नोति ॥

(उद्योतः) भाष्ये गतिसंज्ञासन्नियुक्तमिति । वैकल्पिकगतिसंज्ञासंनियुक्तमित्यर्थः ॥ एकदेशेति । एवं च लवणीकृत्येत्यनिष्टं स्यादिति भावः ॥

(प्रयोजनान्तरपरिहारभाष्यम्)

एतदपि नास्ति प्रयोजनम् । लवणशब्दस्यायं विभाषा लवणंशब्द आदेशः क्रियते । यदि च लवणीशब्दस्यापि विभाषा लवणंशब्द आदेशो भवति न किंचिद् दुष्यति । त्रैशब्द्यं चेह साध्यं तच्चैवं सति सिद्धं भवतीति ॥ साक्षात्प्रभृतीनि च ॥ ७३ ॥

(प्रदीपः) त्रैशब्द्यमिति । त्रय एव शब्दास्त्रैशब्द्यम् । लवणं कृत्वा लवणंकृत्य लवणीकृत्येति ॥ ७३ ॥

(उद्योतः) भाष्ये—लवणंशब्द इति । लवणमिति गणपाठः। तस्य लवणशब्दस्य लवणमित्यादेश इत्यर्थः । गतिसंज्ञासंनियुक्तत्वाद् गतिसंज्ञाभावे आदेशाभाव इति भाष्ये विभाषेत्युक्तम् । अनेन गतित्वाभावे च लवणीशब्दे पूर्वेण गतित्वमिति भावः॥७३॥

(२०५ संज्ञानियमसूत्रम् ।१।४।४ आ. १० सू.)

३१९ ते प्राग्धातोः ॥ १ । ४।७९ ॥

(नियमाकारनिर्णयाधिकरणम्)

(आक्षेपभाष्यम्)

किमिदं प्राग्धातुवचनं प्रयोगनियमार्थम्—एते प्रागेव धातोः प्रयोक्तव्याः । आहोस्वित्संज्ञानियमार्थम्—एते प्राक् चाप्राक् च प्रयोक्तव्याः प्राक्प्रयुज्यमानानां गतिसंज्ञा भवतीति ॥

(प्रदीपः) ते प्राग्धातोः ॥ ७९ ॥ किमिदमिति । नियमद्वयसंभवात्प्रश्नः। तत्र यदा प्रयोगनियमस्तदा त इत्यनेन लब्धगत्युपसर्गसंज्ञाः परामृश्यन्ते । यदा तु संज्ञानियमस्तदा प्रादय उपनिपत्पर्यन्ताः स्वरूपेणैव प्रत्यवमृश्यन्ते संज्ञाया अनिष्पादात्। अनेनैकवाक्यतामापन्नैः पूर्वसूत्रैस्तस्या विधानात्॥

(उद्योतः) ते प्राग्धातोः ॥ ७९ ॥ ननु ते इत्यनेन यदि लब्धसंज्ञानां परामर्शस्तदा द्वितीयपक्षानुत्थितिरेव, केवलानां परामर्शे त्वेतत्संज्ञारहितानामप्याद्यपक्षे व्यवहितप्रयोगानापत्तिरत आह—तत्र यदेति ॥ अनिष्पादादिति । संज्ञानियमपक्षेऽस्य परिभाषात्वेनैकवाक्यतयैव संज्ञाविधानादिति भावः । प्रत्यासत्तेश्च गत्युपसर्गसंज्ञाविषय एव नियमो न निपातसंज्ञाविषयक इति बोध्यम् ॥

(विशेषप्रश्नभाष्यम्)

कश्चात्र विशेषः? ॥

(११५३ प्रथमपक्षदूषणवार्तिकम् ॥ १ ॥)

॥ * ॥ प्राग्धातुवचनं प्रयोगनियमार्थमिति चेदनुकरणस्येतिकरणपरप्रतिषेधोऽनिष्टशब्दनिवृत्त्यर्थः ॥ * ॥

(भाष्यम्) प्राग्धातुवचनं प्रयोगनियमार्थमिति चेदनुकरणस्येतिकरणपरप्रतिषेधो वक्तव्यः ॥ किं प्रयोजनम्?। अनिष्टशब्दनिवृत्त्यर्थः । अनिष्टशब्दता मा भूदिति ॥

(प्रदीपः) अनुकरणस्येति । अनुकरणं चानितिपरमित्यत्रैतद्व्याख्यातम् ॥

(११५४ दूषणान्तरवार्तिकम् ॥ २ ॥)

॥*॥ छन्दसिपरव्यवहितवचनं च ॥*॥

(भाष्यम्) "छन्दसि परेऽपि" "व्यवहिताश्च" इति वक्तव्यम् ॥

(११५५ द्वितीयपक्षदृष्टापत्तिवार्तिकम् ॥ ३)

॥ * ॥ संज्ञानियमे सिद्धम् ॥ * ॥

(भाष्यम्) संज्ञानियमे सति सिद्धमेतद्भवति ॥

(प्रदीपः) **संज्ञानियमे सिद्धमिति** ॥ अनितिपरमिति न वक्तव्यम् । अनेनैव नियमेन खाडिति कृत्वेत्यत्र संज्ञानिरासस्य सिद्धत्वात् । उत्तरं च सूत्रद्वयं न कर्तव्यं भवति । परव्यवहितानां गत्युपसर्गसंज्ञयोर्निवारणान्न तु प्रयोगस्येत्यर्थः ॥

(उद्योतः) ननु संज्ञानियमे इदं व्यर्थम् अप्राक्प्रयुज्यमानानामपि संज्ञायां जातायामनिष्टाभावादत आह—**अनितीति।** एवं चैवमाद्यकरणमेवात्र पक्षे सूत्रस्य फलमिति भावः ॥ **नतु प्रयोगस्येति।** न चाप्राप्तसंज्ञानां परव्यवहितानां संज्ञार्थमुत्तरसूत्रम्, फलाभावात् परव्यवहितानामेकाकिनामेव छन्दसि प्रयोगेण **गतिर्गतावि**ति फलस्य वक्तुमशक्यत्वात् । एवं च संज्ञानियमे प्रयोगनियमपक्षीयफलसिद्धिस्थितयाकरणलाघवं चेति भावः ॥

(द्वितीयपक्षाङ्गीकारभाष्यम्)

अस्तु तर्हि संज्ञानियमः ॥

(प्रदीपः) **अस्त्विति ।** लाघवादस्यैव पक्षस्य युक्तत्वात् ॥

(सूत्रप्रत्याख्यानाधिकरणम्)

(११५६ प्रत्याख्यानवार्तिकम् ॥ ४ ॥)

॥ * ॥ उभयोरनर्थकं वचनमनिष्टादर्शनात् ॥ * ॥

(भाष्यम्) **उभयोरपि पक्षयोर्वचनमनर्थकम् । किं कारणम् ? । अनिष्टादर्शनात् । नहि कश्चित्प्रपचतीति प्रयोक्तव्ये पचति प्रेति प्रयुङ्क्ते । यदि चानिष्टं दृश्येत, ततो यत्नार्हं स्यात् ॥**

(प्रदीपः) **उभयोरिति ।** भाषायां परव्यवहितप्रयोगो न दृश्यते, तत्र किं प्रयोगनियमेन वा संज्ञानियमेन वा । यत्र हि लोके संकीर्णः प्रयोगो यथा गौर्गावीति तत्रासाधुपरिहाराय साध्वनुज्ञानं कर्तव्यम् । न त्वसंकीर्ण एव प्रयोगे स्थिते शास्त्रस्य किंचिदस्ति प्रयोजनम् । छन्दसि तु परव्यवहितप्रयोगो दृश्यत एव ॥

(उद्योतः) नन्वापाद्यमानव्यवहितपरप्रयोगनिवृत्तये सूत्रं स्यादत आह—**भाषायामिति ।** एवं चानभिधानेन प्रत्याख्यानमिति भावः ॥ **न दृश्यत इति ।** शिष्टानां यज्ञकर्मणोऽन्यत्रापीति शेषः ॥

(११५७ प्रत्याख्यानपरिहारवार्तिकम् ॥ ५ ॥)

॥ * ॥ उपसर्जनसन्निपाते तु पूर्वपरव्यवस्थार्थम् ॥ * ॥

(भाष्यम्) **उपसर्जनसन्निपाते तु पूर्वपरव्यवस्थार्थमेतद्वक्तव्यम्—'ऋषभं कूलमुद्रुजम्' 'ऋषभं कूलमुद्वहम्' । अत्र गतेः प्राग्धातोः प्रयोगो यथा स्यात् ॥**

(प्रदीपः) **उपसर्जनसन्निपात इति ।** यद्यपि लोके विपरीतः प्रयोगो न दृश्यते, तथापि कूलमुद्रुजमित्यादौ द्वयोरप्युपपदत्वात्समासे कृते **उपसर्जनं पूर्वमिति** शास्त्रदर्शनात्पर्यायेण पूर्वनिपातेन भाव्यं कूलमुद्रुज उत्कूलंरुज इत्येवं यो भ्राम्येत्तं प्रतीदं सूत्रं कर्तव्यमित्यर्थः ॥

(उद्योतः) **द्वयोरप्युपपदत्वादिति ।** यद्यपि समासः क्रमेणैव, तथापि कदाचित्पूर्वं कूलशब्देन समासः, तत उदेति विपरीतः प्रयोगः स्यादिति भावः । तथा च सूत्रसार्थक्याय प्रयोगनियमपक्ष एवादर्त्तव्यः । तस्मिंश्च कृतेऽ**नितीत्या**द्यपि सर्वं कार्यमिति तात्पर्यम् ॥

(आक्षेपभाष्यम्)

यद्युपसर्जनसन्निपाते पूर्वपरव्यवस्थार्थमिदमुच्यते, सुकटंकराणि वीरणानीत्यत्र गतेः प्राग्धातोः प्रयोगः प्राप्नोति ॥

(प्रदीपः) **सुकटंकराणीति ।** सुखेन कटाः क्रियन्त इति **कर्तृकर्मणोश्च भूकृञोरि**ति खल् । तत्रास्मान्नियमात्कटंसुकराणीति प्राप्नोति ॥

(उद्योतः) ननु सुस्थितं कटं कुर्वन्तीत्यर्थान्नायं गतिरुपसर्गो वेति न दोषोऽत आह—**सुखेनेति ।** उत्तरसूत्रे एव खलः खित्त्वस्य सफलत्वादिति भावः ॥ ईषच्छब्दयोगे तु स खल् नानभिधानात् । अन्यथेषदाढ्यंभवं भवता, ईषदाढ्यंकरो मैत्रो भवतेत्यादावीषतोऽगतित्वेन खित्त्वस्य चारितार्थ्याद्भाष्यासंगतिरेव स्यादिति बोध्यम् ॥

(आक्षेपपरिहारभाष्यम्)

आचार्यप्रवृत्तिर्ज्ञापयति—'नात्र गतेः प्राक्प्रयोगो भवति' । यदयम् "ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल्" इति खकारमनुबन्धं करोति ॥ कथं कृत्वा ज्ञापकम् ? । खित्करणे एतत्प्रयोजनं "खिति" इति मुम् यथा स्यात् । यदि चात्र गतेः प्राक्प्रयोगः स्यात्, खित्करणमनर्थकं स्यात् । अस्त्वत्र मुम् । 'अनव्ययस्य' इति प्रतिषेधो भविष्यति । पश्यति त्वाचार्यः—'नात्र गतेः प्राग् धातोः प्रयोगो भवति' इति, ततः खकारमनुबन्धं करोति ॥

(प्रदीपः) **अस्त्वत्रेति ।** शास्त्रेण प्राप्नोतु प्रतिषेधात्तु नैव प्रयुज्यत इत्यर्थः ॥ खित्करणादव्ययस्यापि भवत्विति चेत् । नैतदस्ति । **अनव्ययस्ये**ति निषेधस्य प्रत्यक्षत्वाद्बाधितुमशक्यत्वात् । प्रयोगनियमस्यान्यत्र सावकाशत्वाद्बाधेऽपि न काचित्क्षतिः ॥

(उद्योतः) नन्वजन्तत्वात्सोर्मुमः प्राप्तिरस्त्येवेत्यत आह—भाष्ये—**अस्त्वत्रेति ।** प्राप्नोत्वित्यर्थः ॥ **प्रत्यक्षत्वादिति ।** विधित्वादित्यर्थः ॥ **प्रयोगनियमस्येति ।** एवं च विधिबाधापेक्षयाऽन्यत्र चरितार्थस्य परिभाषारूपत्वेन गुणभूतस्य बाध उचित इति भावः ॥

(प्रत्याख्यानसाधकभाष्यम्)

नैतदस्ति ज्ञापकम् । यद्यत्र गतेः प्राक्प्रयोगः स्यात्, स्यादेवात्र सुमागमः । कथम्? । 'कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणं भवति' इति ॥

(प्रदीपः) **स्यादेवेति** । कटंसुकराणीत्येवमपि प्रयोगे स्यादेव सुमित्यर्थः ॥ ७९ ॥

(उपसंहारभाष्यम्)

तस्मादार्थ एवमर्थेन प्राग्धातुवचनेन ॥

(उद्योतः) भाष्ये—**एवमर्थेनेति** । प्रयोगनियमार्थेनेत्यर्थः । सुकटंकराणीत्यसिद्धेरिति भावः ॥

(आक्षेपभाष्यम्)

कथम्-'ऋषभं कूलमुद्रुजम्' 'ऋषभं कूलमुद्वहम्'?॥

(आक्षेपपरिहारभाष्यम्)

नैष दोषः ॥ नैष उदिरुपपदम् । किं तर्हि? । विशेषणम् । "उदि कूले रुजिवहोः" उत्पूर्वाभ्यां रुजिवहिभ्यां कूले उपपदे इति ॥ ते प्राग्धातोः ॥७९

(उद्योतः) ननु सूत्राभावे संज्ञानियमेऽपि वोत्कूलंरुज इति विपरीतप्रयोगापत्तिरत आह—भाष्ये—**नैष उदिरिति** । तस्मात्प्रयोगनियमार्थं संज्ञानियमार्थं वोभयथापि सूत्रं न कार्यमेव । आद्ये सुकटंकराणीत्यसिद्धेः, अन्त्ये कटंसुकराणीत्यस्याप्यापत्तेः । अनभिधानेन वारणे तु व्यर्थमेव सूत्रमित्याशयः ॥ यत्तु भ्रमनिवृत्त्यर्थेऽपि सूत्रे संज्ञानियमपक्ष एवादर्तव्यः कटंसुकराणि सुकटंकराणीत्युभयविधप्रयोगसिद्धये इति स्थितमिति । तन्न । कटंसुकराणीत्यस्येष्टत्वे मानाभावात् । अत्र गतेः प्राग्धातोः प्रयोगः प्राप्नोति । यद्यत्र गतेः प्राक् प्रयोगः स्यादित्यादिशब्दैस्तदनिष्टत्वस्यैव लाभादिति दिक् ॥ ७९ ॥

(इति विधिशेषप्रकरणे निपातप्रकरणे गत्युपसर्गप्रकरणम्)

(अथ निपातसंज्ञाप्रकरणे कर्मप्रवचनीयसंज्ञाप्रकरणम्)

(२०६ कर्मप्रवचनीयसंज्ञाधिकारसूत्रम् ॥ १ ।

४ । ४ आ. ११ सू.)

३२२ कर्मप्रवचनीयाः ॥ १ । ४ । ८२॥

(महासंज्ञाकरणस्यान्वर्थतासाधनाधिकरणम्)

(आक्षेपभाष्यम्)

किमर्थं महती संज्ञा क्रियते? ॥

(प्रदीपः) **कर्मप्रवचनीयाः ॥ ८२ ॥ किमर्थमिति** । लाघवार्थत्वात्संज्ञाकरणस्य लाघवप्रकर्षाय एकाक्षरा द्व्यक्षरा वा संज्ञा कार्येति भावः ॥

(उद्योतः) **कर्मप्रवचनीयाः ॥ ८२ ॥** ननु संज्ञां विना तत्प्रयुक्तकार्यासिद्धिरत आह—लाघवार्थत्वादिति ॥

(समाधानभाष्यम्)

अन्वर्थसंज्ञा यथा विज्ञायेत—कर्म प्रोक्तवन्तः कर्मप्रवचनीया इति ॥

(प्रदीपः) **अन्वर्थसंज्ञेति** । अर्थमनुगता अर्थेन वा अनुगता अङ्गीकृतप्रवृत्तिनिमित्ता या संज्ञा साऽन्वर्थसंज्ञा ॥ **कर्म प्रोक्तवन्त इति** । प्रयुज्यमाने क्रियापदे क्रियाविशेषं द्योतितवन्त इत्यर्थः ॥

(उद्योतः) ननु सर्वापि संज्ञा ऽर्थं प्रयोजनमनुगतैवेत्यत आह—**अर्थमिति** । अर्थशब्दोऽभिधेयपर इति भावः ॥ **अङ्गीकृतप्रवृत्तिनिमित्तेति** । अङ्गीकृतयोगार्थप्रवृत्तिनिमित्तेत्यर्थः । एवं च योगरूढा संज्ञाऽन्वर्थसंज्ञेच्यते ॥ भाष्ये—**कर्म प्रोक्तवन्त इति** । कर्म क्रियां क्रियागतविशेषमित्यर्थः । भूते कृत्यल्युटो बहुलमिति कर्त्तर्यनीयः ॥ ननु निपातानां द्योतकत्वात् प्रोक्तवन्त इत्यसंगतमत आह—**प्रयुज्यमाने इति** । सुखमनुवभूवेत्यादौ द्योतकेऽपि प्रोक्तवत्त्वमस्त्येवेत्यर्थः ॥

(अनुयोगभाष्यम्)

के पुनः कर्म प्रोक्तवन्तः? ॥

(समाधानभाष्यम्)

ये संप्रति क्रियां नाहुः ॥

(प्रदीपः) **क्रियां नाहुरिति** । क्रियागतं विशेषं न द्योतयन्तीत्यर्थः ॥

(उद्योतः) ननु निपाताः कदापि क्रियां न वदन्तीति संप्रतीत्ययुक्तमत आह—**क्रियागतमिति** ॥

(अनुयोगभाष्यम्)

के च संप्रति क्रियां नाहुः? ॥

(समाधानभाष्यम्)

ये अप्रयुज्यमानस्य क्रियामाहुः ते कर्मप्रवचनीयाः ॥ कर्मप्रवचनीयाः ॥ ८२ ॥

(प्रदीपः) **ये अप्रयुज्यमानस्य क्रियामाहुरिति** । शाकल्यस्य संहितामनु प्रावर्षदिति वाक्येऽप्रयुज्यमानस्य निशमेर्या क्रिया तत्कृतो वर्षसंहितयोर्हेतुमद्भावलक्षणः संबन्ध इत्ययमर्थोऽनुशब्दसन्निधौ प्रतीयते । तदयमनुः संहितामिति द्वितीययाभिहितं संबन्धमवच्छिनत्ति । विशिष्टक्रियाभिजनितत्वेन हेतुहेतुमद्भावलक्षणविशेषरूपतया वा तत्सन्निधौ संबन्धस्य संप्रत्ययात् । तथा हि—क्रियायास्तावदयं न वाचकः, कारकविभक्तिप्रसङ्गात् । शेषविभक्तिसंबन्धस्याप्रतीतिप्रसङ्गाच्च । अत एव न क्रियापदाक्षेपकः । यथा प्रादेशं विपरिलिखतीति

विशब्दो विमानक्रियाया आक्षेपक इति प्रादेशमिति कर्मणि द्वितीया । क्रियाविशेषद्योतकत्वमपि क्रियापदसन्निधाने दृष्टमिति अत्र न संभवतीति पारिशेष्यात्संबन्धावच्छेदहेतुरनुः संपद्यते । तथा चोक्तं हरिणा—

'क्रियाया द्योतको नायं संबन्धस्य न वाचकः ।
नापि क्रियापदाक्षेपी संबन्धस्य तु भेदकः' ॥

इति ॥ तत्र **क्रियामाहुरि**ति क्रियाशब्देन तदुपजनितसंबन्धविशेष उपचारादुच्यते ॥ **आहु**रित्यस्यापि द्योतयन्तीत्ययमर्थः ॥ क्वचित्तु प्रवृत्तिनिमित्ताभावेपि वचनसामर्थ्यादियं संज्ञा प्रवर्तते । यथा **सुः पूजाया**मिति षत्वादिनिवृत्तये गत्युपसर्गसंज्ञाबाधनार्था ॥ ८२ ॥

(उद्द्योतः) यदि संप्रति क्रियागतं विशेषं न द्योतयन्ति किं तर्हि द्योतयन्तीत्यत्राह—भाष्ये—**येऽप्रयुज्यमानस्ये**ति । [?**तद्वाच्यां**] **क्रियां** तद्वाच्यक्रियाकृतसंबन्धविशेषम् ॥ तदेवोपपादयति—**शाकल्यस्ये**ति ॥ तत्र संबन्धावच्छेदप्रकारमाह—**विशिष्टक्रिये**ति । निशमनक्रियाजनितसंबन्धेन संहितासंबन्धि वर्षणमिति बोध इति भावः ॥ एवं बोधाननुभवादाह—**हेतुमदि**ति । संहिताहेतुकं प्रवर्षणमिति बोधः ॥ वस्तुतः क्रियाद्वारको यः संबन्धः स हेतुत्वादिना भासते इति तत्त्वम् ॥ **क्रियायाः**, क्रियागतविशेषस्य **वाचको** द्योतक इत्यर्थः ॥ **कारकविभक्तिप्रसङ्गादि**ति । वृक्षंवृक्षं प्रति सिञ्चतीत्यादावुपपद**विभक्तेरि**ति न्यायेन कर्मणि द्वितीयैव स्यादित्यर्थः ॥ मम तु प्रतिद्योत्यसंबन्धेनान्वये कारकविभक्तेरप्राप्तावियमिति भावः ॥ ननु को विशेषोऽत्र आह—**शेषे**ति । शेषविभक्त्यर्थसंबन्धस्येत्यर्थः । अनेन कारकविभक्त्यर्थस्यापि संबन्धत्वं सूचितम् । संबन्धस्यापि न वाचको, द्वितीययैव तत्प्रतीतेः ॥ **अत एवे**ति । संबन्धाप्रतीतिप्रसङ्गादेवेत्यर्थः । तदाक्षेपे तां प्रति कर्मत्वादिनैवान्वयसंभवादिति भावः ॥ **कर्मप्रवचनीययुक्ते** इत्यस्य वैयर्थ्यं च स्यादित्यपि बोध्यम् ॥ क्रियागतविशेषद्योतकत्वाभावे युक्त्यन्तरमप्याह—**क्रियाविशेषे**त्यादि ॥ **न संभवतीति** । अनु हरिं सुरा इत्यादौ क्रियापदासन्निधानादिति भावः ॥ **पारिशेष्यादि**ति । एवं च संबन्धसामान्ये प्राप्तषष्ठीबाधाय द्वितीयार्थमयमारम्भ इति भावः ॥ कारिकायां **क्रियाया** इत्यस्य क्रियागतविशेषस्येत्यर्थः । **भेदको** द्योतकः ॥ ८२ ॥

——०:०:०——

(२०७ कर्मप्रवचनीयसंज्ञासूत्रम् ॥ १।४।४ आ. १२ सू.)

३२३ अनुर्लक्षणे ॥ १ । ४ । ८३ ॥

(सूत्रारम्भप्रयोजनाधिकरणम्)

(आक्षेपभाष्यम्)

किमर्थमिदमुच्यते ? ॥

(प्रदीपः) **अनुर्ल** ॥ ८३ ॥ **किमर्थमि**ति । लक्षणेत्थंभूताख्यानेत्यनेनैव सिद्धत्वादिति प्रश्नः ॥

(समाधानभाष्यम्)

कर्मप्रवचनीयसंज्ञा यथा स्यात् । गत्युपसर्गसंज्ञे मा भूतामिति ॥ किं च स्यात् ? । शाकल्यस्य संहितामनु प्रावर्षत् "गतिर्गतौ" इति निघातः प्रसज्येत ॥

(प्रदीपः) इतरः शिष्यबुद्धिपरीक्षार्थं जात्युत्तरं ददाति—**कर्मप्रवचनीयसंज्ञे**ति ॥ **निघात** इति । निपातत्वादाद्युदात्तोत्रानुरिष्यते ॥

(उद्द्योतः) **अनुर्लक्षणे** ॥ ८३ ॥ जात्युत्तरम्, असदुत्तरम् । तत्त्वं न लक्षणेत्थमित्यनेनैव गत्यादिसंज्ञाबाधसिद्धेरिति भावः ॥

(समाधानबाधकभाष्यम्)

यद्येवं वेरपि कर्मप्रवचनीयसंज्ञा वक्तव्या । वेरपि निघातो नेष्यते—प्रादेशं विपरिलिखति ॥

(समाधानसाधकभाष्यम्)

अस्त्यत्र विशेषः । नात्र वेर्लिखिं प्रति क्रियायोगः ॥ किं तर्हि ? । अप्रयुज्यमानम्—प्रादेशं विमाय परिलिखतीति ॥

(प्रदीपः) **नात्र वेरि**ति । नहि प्रादेशो लिख्यते ॥ **किं तर्ही**ति । धातुं प्रतीति वाक्यशेषः । प्रादेशे च योग्या क्रिया वेराक्षेप्येति सामर्थ्याद्विमानक्रियाया आक्षेपः ॥

(उद्द्योतः) **नहि प्रादेश** इति । किं तु तत्परिच्छिन्नं भूम्यादीति भावः ॥ **धातुं प्रती**ति । अप्रयुज्यमानधातुबोध्यक्रियया योगे इति फलितोर्थः ॥ ननु या काचित् क्रियाक्षेप्येत्यत आह—**प्रादेशे चे**ति । प्रादेशान्वये इत्यक्षरार्थः । एवं च **गतिर्गता**वित्यत्र प्रत्यासत्त्यैकक्रियानिरूपितगतित्ववतोर्ग्रहणेन नात्र निघातप्राप्तिरिति भावः ॥

(समाधानबाधकभाष्यम्)

यद्येवम्, अनोरपि कर्मप्रवचनीयसंज्ञया नार्थः । अनोरपि हि न वृषिं प्रति क्रियायोगः ॥ किं तर्हि ? । अप्रयुज्यमानम्—शाकल्येन सुकृतां संहितामनुनिशम्य देवः प्रावर्षत् ॥

(प्रदीपः) **शाकल्येन सुकृतामि**ति । अत्र वाक्ये या निशमनक्रिया तत्कृतो वर्षसंहितयोः संबन्धावच्छेदोऽनुना प्रतिपाद्यत इति नास्ति वर्षक्रियायोगोनोरित्यर्थः ॥

(उद्द्योतः) ननु शाकल्यस्य संहितामित्याद्युदाहरणे संबन्धावच्छेदकताया अन्वादीनामुक्तत्वेन क्रियापदाक्षेपोऽसङ्गतो, **द्वितीया** यथा स्यादित्युत्तरग्रन्थासङ्गतिश्चेत्यत आह—**अत्र वाक्ये** इति ॥ शाकल्येन सुकृतामिति वाक्ये ॥ **प्रतिपाद्यते** इति । शाकल्यस्य

संहितामित्युदाहरणे इति शेषः । गत्यादिसंज्ञापवादत्वं त्वस्या एकशेषस्य द्वन्द्वापवादत्ववद् बोध्यम् । **शाकल्येन सुकृतामि**-त्युक्त्या तत्तदृषिकृतत्वं शाखास्वभ्युपैति । स्पष्टं चेदं **तेन प्रोक्त**-मितिसूत्रे भाष्ये ॥ **नास्ति वर्षेति** । एवं च **गतिर्गताविति**स्य न प्राप्तिः । क्रियायोगश्च तद्गतविशेषद्योतकतारूप एव गतिसंज्ञानिमित्त-मिति भावः । एवं चैतद्द्योत्यसंबन्धस्य क्रियान्वयेऽपि न क्षतिरिति तात्पर्यम् ॥

(समाधानसाधकभाष्यम्)

एवं तर्हि प्रयोजनम्—द्वितीया यथा स्यात् "कर्म-प्रवचनीययुक्ते द्वितीया" इति ॥

(समाधानपरिहारभाष्यम्)

अत उत्तरं पठति ॥

(उद्द्योतः) अत उत्तरमिति । सार्वविभक्तिकस्तसिः । अस्योत्तरमित्यर्थः ॥

(११५७ वैयर्थ्यवार्तिकम् ॥ १ ॥)

॥ * ॥ अनुर्लक्षणेवचनानर्थक्यं सामा-न्यकृतत्वात् ॥ * ॥

(भाष्यम्) **अनुर्लक्षणेवचनमनर्थकम् ॥ किं कार-णम्? । सामान्यकृतत्वात् । सामान्येनैवात्र कर्म-प्रवचनीयसंज्ञा भविष्यति "लक्षणेत्थंभूताख्यान-भागवीप्सासु प्रतिपर्यनवः" इति ॥**

(प्रदीपः) **अनुर्लक्षण इति** । सूत्रानुकरणमेतत् ॥ **सामान्यकृतत्वादिति** । सामान्यं साधारणं यत्सूत्रमर्था-न्तरसंश्रयन्तरनिर्देशात् । तेनैव कृतत्वात्सिद्धत्वादित्यर्थः ॥

(उद्द्योतः) नन्वनुरिति प्रथमान्तस्य **वचनमनर्थकमित्यनेना**-न्वयोऽनुचित इत्यनोरिति वक्तुमुचितमत आह—**सूत्रेति** । **अनु-र्लक्षणे** इत्येतद्वचनमित्यर्थः ॥ ननु तस्यापि **विशेषत्वात्सामान्येने**-त्ययुक्तमत आह—**सामान्यमिति** ॥

(११५८ वैयर्थ्यबाधकवार्तिकम् ॥ २ ॥)

॥ * ॥ हेत्वर्थे तु वचनम् ॥ * ॥

(भाष्यम्) **हेत्वर्थमिदं वक्तव्यम् । हेतुः शाक-ल्यस्य संहिता वर्षस्य, न लक्षणम् ॥**

(प्रदीपः) **हेत्वर्थमिति** । हेतुरर्थः प्रयोजनम्—प्रयो-जक एतस्य वचनस्येत्यर्थः ॥ **हेतुरिति** । अन्वयव्यतिरे-काभ्यां वर्षं प्रति संहितायाः कारणत्वावगमादित्यर्थः ॥

(उद्द्योतः) ननु साध्यतयाऽस्य हेतुः प्रयोजनं नेत्यत आह—**हेतुरिति** ॥ **प्रयोजक इति** । प्रयुज्यतेऽनेनेति व्युत्पत्तेः ॥ भाष्ये—**हेतुः शाकल्यस्येति** । **लक्षणेत्थमितिसूत्रे** ज्ञापकस्यैव लक्षणशब्देन ग्रहाद् हेतोश्च तस्याभावान्न तेन सिद्धिरित्यर्थः ॥ तत्र हेतुत्वमुपपादयति—**अन्वयेति** ॥

(तृतीयाक्षेपभाष्यम्)

किं वक्तव्यमेतत्? ॥

(प्रदीपः) **किं वक्तव्यमिति** । हेतोर्लक्षणत्वं नास्तीति किं परिभाषितव्यमिति[3] पृच्छति ॥

(सिद्धान्तिसमाधानभाष्यम्)

नहि ॥ कथमनुच्यमानं गंस्यते? । लक्षणं हि नाम स भवति येन पुनःपुनर्लक्ष्यते, न यः सकृदपि निमित्तत्वाय कल्पते । सकृच्चासौ शाकल्येन सु-कृतां संहितामनुनिशम्य देवः प्रावर्षत् ॥

(प्रदीपः) **येन पुनः पुनरिति** । पौनःपुन्येन साह-चर्यावगमे लक्ष्यलक्षणभावो भवतीति भावः ॥

(उद्द्योतः) भाष्ये—**येन पुनःपुनरिति** । गृहीतसंबन्धे-नेति शेषः ॥ लक्ष्यलक्षणभाव इति । तद्व्यवहार इत्यर्थः ॥ न यः सकृदपीति । गृहीतसंबन्ध इति शेषः ॥ **निमित्तत्वाय** । तेन तत्कारणमेवेत्यर्थः ॥

(तृतीयाक्षेपभाष्यम्)

स तर्हि तथा निर्देशः कर्तव्यः "अनुर्हेतौ" इति ॥ अथेदानीं लक्षणेन हेतुरपि व्याप्तः । नार्थोऽनेन? ॥

(प्रदीपः) **अथेदानीमिति** । येनोक्तं **स तर्हि तथेति**, स एव सन्दिहानः पृच्छति ॥ **व्याप्त इति** । हेतुविषयत्वा-ल्लक्षणस्य तेन हेतुर्व्याप्तो भवति ॥

(उद्द्योतः) **स तर्हीति** । कृतेपि सूत्रे हेतोर्लक्षणशब्देन व्यवहाराभावादिति भावः ॥ ननु **हेत्वर्थमिदमित्युक्तवन्तं** प्रति हेतोर्लक्षणत्वाभावादनुर्हेताविति वक्तव्यमित्यन्येनोक्ते, **अथेदानी**-मितिग्रन्थः स्वरसतो हेत्वर्थवादिन इति लभ्यते । तत्र युक्तं **नार्थो-ऽनेनेति** वाक्यशेषविरोधात्, नापि सूत्रप्रत्याख्यानवादिनस्तस्य विच्छिन्नत्वादत आह—**येनोक्तमिति** ॥ ननु हेतुत्वं विना लक्ष-णत्वस्य विद्युद्वृक्षविषये सत्त्वेन लक्षणत्वं विना हेतुत्वस्य च दण्डादौ दर्शनेन 'लक्षणेन हेतुर्व्याप्त' इत्यसङ्गतमत आह—**हेतुविषय-त्वादिति** । प्रकृतोदाहरणे इति शेषः ॥ **व्याप्त** इत्यस्य **संबद्ध** इत्यर्थो द्रष्टव्यः ॥

(समाधानभाष्यम्)

लक्षणेन हेतुरपि व्याप्तः । नह्यवश्यं तदेव ल-क्षणं भवति—येन पुनःपुनर्लक्ष्यते ॥ किं तर्हि? ।

यत्सकृदपि निमित्तत्वाय कल्पते तदपि लक्षणं भवति । तद्यथा—अपि भवान्कमण्डलुपाणिं छात्रमद्राक्षीदिति । सकृदसौ कमण्डलुपाणिश्छात्रो दृष्टस्तस्य तदेव लक्षणं भवति ॥

(प्रदीपः) लक्षणेनेति । सिद्धान्तवादी ॥ तदपि लक्षणमिति । कार्योत्पत्तिनिमित्तमपि तद्विशेषावगमहेतुत्वाल्लक्षणं भवतीत्यर्थः ॥

(उद्द्योतः) ननु भूयो दर्शनाभावात्कथं ज्ञापकत्वमत आह—भाष्ये—नावश्यमिति ॥ तद्विशेषावगमेति । कालविशेषावच्छिन्नदृष्टत्वावगमेत्यर्थः । यो मे कमण्डलुपाणिश्छात्रः पूर्वं दृष्टः सोऽद्य त्वया दृष्ट इत्यपि भवानिति वाक्यार्थः ॥ लक्षणत्वं न व्याप्यत्वापरपर्यायमेव, किं तूपलक्षकत्वरूपमपीति भावः । एवं च लक्षणेत्थमित्यत्रापि लक्षणशब्देन हेतोरभिधानादिदं व्यर्थं स्यादत आह—भाष्ये—तदेवेति ॥

(प्रयोजनभाष्यम्)

एतदेव तर्हि प्रयोजनम्—द्वितीया यथा स्यात् "कर्मप्रवचनीययुक्ते द्वितीया" इति ॥

(परिहारभाष्यम्)

एतदपि नास्ति प्रयोजनम् । सिद्धात्र द्वितीया "कर्मप्रवचनीययुक्ते" इत्येव ॥

(परिहारबाधकभाष्यम्)

न सिध्यति । परत्वाद्धेत्वाश्रया तृतीया प्राप्नोति ॥ [एवमर्थमिदमुच्यते] ॥ अनुर्लक्षणे ॥८३॥

(प्रदीपः) परत्वादिति । येन नाप्राप्तिन्यायेन "कर्मप्रवचनीययुक्ते द्वितीया" षष्ठ्या एव बाधिका । तां तु परत्वात्तृतीया बाधेत । पुनःसंज्ञाविधाने तु स्थानान्तरप्राप्त्या द्वितीया हेतुतृतीयां बाधते ॥ ८३ ॥

(उद्द्योतः) ननु विध्यन्तरपूर्वकत्वेन द्वितीयाया अपवादत्वात्कथं तृतीयाबाध्यत्वमत आह—येन नेति ॥ बाधेतेति । यत्र हेतुत्वं न भासते तत्र लक्षणेत्थमित्येतत्संज्ञाप्रयुक्ता द्वितीया सावकाशा यथा वृक्षमनु विद्योतत इत्यादौ, धनेन कुलमित्यादौ चानोरभावाद्धेतुतृतीया सावकाशेति भावः ॥ ननु कृतेऽप्यस्मिन् द्वितीयया कथं बाधोऽत आह—पुनः संज्ञेति । पुनः संज्ञाविधानेन पुनर्द्वितीयाविधानं कल्प्यते । तच्च तृतीयाप्राप्त्युत्तरकालत्वात् स्थानान्तरप्राप्तमित्युच्यते इति बोध्यम् ॥ ८३ ॥

(२०८ कर्मप्रवचनीयसंज्ञासूत्रम् ॥ १।४।४ आ. १३ सू.)

३२८ आङ्मर्यादावचने ॥१।४।८८॥

(अभिविधौ कर्मप्रवचनीयसंज्ञासाधनाधिकरणम्)

(११५९ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ आङ् मर्यादाभिविध्योः ॥ * ॥

(भाष्यम्) आङ्मर्यादाभिविध्योरिति वक्तव्यम् । इहापि यथा स्यात्—आकुमारं यशः पाणिनेरिति ।

(प्रदीपः) आङ् मर्या ॥ ८८ ॥ आङ् मर्यादाभीति । अन्यत्र मर्यादाभिविध्योर्भेदेन निर्देशदर्शनाद् विना तेनेति मर्यादा, सह तेनेत्यभिविधिरित्यर्थभेदं मत्वा वार्तिकं पठति ॥ आकुमारमिति । कुमारानपि यशः प्राप्तमित्यर्थः ॥

(उद्द्योतः) आङ् मर्यादा ॥ ८८ ॥ ननु परिच्छेदहेतुमात्रं मर्यादेति सिद्धमेवाभिविधावपीत्यत आह—अन्यत्रेति ॥

(तृतीयाक्षेपभाष्यम्)

तत्तर्हि वक्तव्यम्? ॥

(सिद्धान्तिभाष्यम्)

न वक्तव्यम् । "मर्यादावचने" इत्येव सिद्धम् । एषाऽस्य यशसो मर्यादा ॥ आङ्मर्यादावचने ॥८८॥

(प्रदीपः) मर्यादावचन इत्येवेति । वचनग्रहणस्येदं प्रयोजनमवान्तरभेदपरिहारेण परिच्छेदहेतुमात्रं मर्यादा यथा गृह्येत ॥ ८८ ॥

(उद्द्योतः) अवान्तरेति । मर्यादाविशेष एवाभिविधिः । मर्यादैव यदा कार्येण युज्यते तदाऽभिविधिः, यदा तु न तदा मर्यादेति विशेषाविवक्षणादिति भावः । तदुक्तं भाष्ये—एषाऽस्य यशसो मर्यादेति । अस्य पाणिनेः । एषा कुमाररूपा । मर्यादा परिच्छेदहेतुरित्यर्थः ॥ ८८ ॥

(२०९ कर्मप्रवचनीयसंज्ञासूत्रम् ॥ १।४।४ आ. १४ सू.)

३२९ लक्षणेत्थंभूताख्यानभागवीप्सासु प्रतिपर्यनवः ॥ १ । ४ । ८९ ॥

(लक्षणादीनां प्रत्यादिद्योत्यत्वाधिकरणम्)

(अनुयोगभाष्यम्)

कस्य लक्षणादयोऽर्था निर्दिश्यन्ते ? ॥

(प्रदीपः) लक्षणेत्थम् ॥ ८९ ॥ कस्येति । किं यथा विभक्तिसमीपादयोऽव्ययार्थास्तथा लक्षणादयः प्रत्यादी-

नाम्। अथ पदान्तरवाच्याः सन्तो विषयभावेन संज्ञायाः प्रत्यादीनां वा निर्दिष्टा इति प्रश्नः॥

(उद्योतः) लक्षणेत्थं॥ ८९॥ प्रत्यादीनां वेति। तेषां तद्विषयत्वं च तद्घटितसंबन्धपरिच्छेदकत्वाद्बोध्यम्॥

(समाधानभाष्यम्)

वृक्षादीनाम्॥

(प्रदीपः) वृक्षादीनामिति। वृक्षं प्रति विद्योतते विद्युदिति वृक्षो विद्योतनस्य लक्षणम्। प्रत्यादयस्तु प्राप्तिक्रियाजनितसंबन्धविशेषावच्छेदहेतवः॥

(उद्योतः) भाष्ये—वृक्षादीनामिति। तदुत्तरविभक्तीनामित्यर्थः। प्रत्यादयस्तु तद्द्योतका इति भावः॥ संबन्धविशेषेति। वृक्षविद्योतनयोः प्राप्तिक्रियाजनितो लक्ष्यलक्षणभाव इति भावः। महासंज्ञाकरणेन क्रियाजनितसंबन्धद्योतकताया एव प्रायेण कर्मप्रवचनीयानामुचितत्वादिति तात्पर्यम्॥

(सूत्रप्रयोजनाधिकरणम्)

(आक्षेपभाष्यम्)

किमर्थं पुनरिदमुच्यते?॥

(प्रदीपः) किमर्थमिति। वृक्षं वृक्षं प्रति सिञ्चतीत्यत्र कर्मत्वाद् द्वितीया सिद्धेति तद्विधानार्थं तावदिदं न भवति। प्रत्यादीनां च क्रियाविशेषानवद्योतनात् क्रियायोगाभावाद्गत्युपसर्गसंज्ञाबाधनार्थमपि नोपयुज्यत इति प्रश्नः॥

(उद्योतः) ननु द्वितीयार्थमिदमावश्यकमत आह—वृक्षं वृक्षं प्रतीति॥ क्रियायोगाभावादिति। तेषां समभिव्याहृतविभक्त्यर्थसंबन्धमात्रद्योतकत्वादिति भावः॥

(समाधानभाष्यम्)

कर्मप्रवचनीयसंज्ञा यथा स्यात्, गत्युपसर्गसंज्ञे मा भूतामिति॥

(समाधानबाधकभाष्यम्)

नैतदस्ति प्रयोजनम्। यत्क्रियायुक्तास्तं प्रति गत्युपसर्गसंज्ञे भवतः। न च वृक्षादीन्प्रति क्रियायोगः॥

(उद्योतः) भाष्ये—न च वृक्षादीन्प्रतीति। प्रतियोगे वृक्षादीनिति द्वितीया संबन्धार्थिका वृक्षाद्युत्तरविभक्त्यर्थसंबन्धिनामेषामित्यर्थः। तत्संबन्धश्च तदर्थसंबन्धपरिच्छेदकत्वेनेति बोध्यम्॥

(समाधानसाधकभाष्यम्)

इदं तर्हि प्रयोजनम् द्वितीया यथा स्यात् "कर्मप्रवचनीययुक्ते द्वितीया" इति। वृक्षं प्रति विद्योतते वृक्षमनु विद्योतते इति॥ एवमर्थमिदमुच्यते॥ लक्षणे०॥ ८९॥

(प्रदीपः) वृक्षं प्रतीति। अकर्मकत्वाद् द्युतेः कर्मणि द्वितीया नास्ति॥ ८९॥

(उद्योतः) अकर्मकत्वादिति। एवमर्थमर्थं प्रति शब्दनिवेश इत्यादौ निविशत्यधिकरणे द्वितीयार्थमपीदं बोध्यम्। सकर्मकयोगेपि कर्मत्वाविवक्षायां संबन्धत्वेन विवक्षायां प्रत्यादिद्योत्यसंबन्धेनान्वयविवक्षायां च द्वितीयार्थमित्यपि बोध्यम्। एतेनाकर्मकत्वाद्...द्वितीया नास्तीति कैयटोक्तेः सकर्मकधातुयोगे कर्मणि द्वितीयैव सिद्धमिति भ्राम्यन्तः परास्ताः॥ ८९॥

(२१० कर्मप्रवचनीयसंज्ञासूत्रम् १।४।४ आ. १५ सू.)

३३२ अधिपरी अनर्थकौ॥ १।४।९२॥

(उक्तार्थस्यापि प्रयोगाधिकरणम्)

(आक्षेपभाष्यम्)

किमर्थमधिपर्योरनर्थकयोः कर्मप्रवचनीयसंज्ञोच्यते?॥

(प्रदीपः) अधिपरी॥ ९२॥ किमर्थमिति। अनर्थकयोः क्रियायोगाभावात्संज्ञान्तरबाधनार्थं संज्ञाविधानं नोपयुज्यते। नापि परियोगे पञ्चमीविधानार्थम्। अपेन साहचर्याद्वर्जनविषयपरियोगे तस्या विधानात्, अपादानसद्भावे चाधिशब्दस्य प्रयोग इव परियोगे तन्निमित्तायाः पञ्चम्याः सिद्धत्वादिति प्रश्नः॥

(उद्योतः) अधिपरी॥ ९२॥ ननु गत्यादिसंज्ञाबाधनं फलमित्यत आह—अनर्थकयोरिति॥ पञ्चमीति। पञ्चम्यपाङ्परिभिरिति सूत्रेणेति शेषः॥ किंचाधिशब्दयोगे पञ्चम्यविधानेपि यथाऽपादानत्वात्सा तथा परियोगेपीत्याह—अपादानेति। आगमनादिक्रियानिरूपितेत्यर्थः। द्वितीयार्थमपि नार्थाभावेन कर्मप्रवचनीययुक्तत्वस्य निरूपयितुमशक्यत्वादिति भावः॥

(समाधानभाष्यम्)

कर्मप्रवचनीयसंज्ञा यथा स्यात्, गत्युपसर्गसंज्ञे मा भूतामिति॥

(समाधानबाधकभाष्यम्)

नैतदस्ति प्रयोजनम्। यत्क्रियायुक्तौ तं प्रति गत्युपसर्गसंज्ञौ भवतः। अनर्थकौ चेमौ॥

(समाधानसाधकभाष्यम्)

इदं तर्हि प्रयोजनम्—पञ्चमी यथा स्यात् "पञ्चम्यपाङ्परिभिः" इति कुतः पर्यागम्यत इति॥

(समाधानबाधकभाष्यम्)

सिद्धं तु "पञ्चम्यपादाने" इत्येव। आतश्चापादानपञ्चम्येव, यत्राधिशब्देन योगे पञ्चमी न विधीयते तत्रापि च श्रूयते—कुतोऽध्यागम्यते इति॥

(समाधानसाधकभाष्यम्)

एवं तर्हि सिद्धे सति यदनर्थकयोरुपसर्गसंज्ञाबाधिकां कर्मप्रवचनीयसंज्ञां शास्ति तज्ज्ञापयत्या-

चार्यः—'अनर्थकानामप्येषां भवत्यर्थवत्कृतम्' इति। किमेतस्य ज्ञापने प्रयोजनम् ? । निपातस्यानर्थकस्य प्रातिपदिकत्वं चोदितं तन्न वक्तव्यं भवति ॥

(समाधानान्तरभाष्यम्)

अथ वा नेमावनर्थकौ ॥ किं तर्ह्यनर्थकावित्युच्यते ? । अनर्थान्तरवाचिनावनर्थकौ, धातुनोक्तां क्रियामाहतुः । तदविशिष्टं भवति । यथा शङ्खे पयः ॥

(प्रदीपः) अथ वेति । पूर्वापरितोषेणेदमुच्यते । यस्य शब्दस्य वाच्यं द्योत्यं वा वस्तु न संभवति तस्य वाक्यार्थेऽनुपयोगात् प्रयोगानुपपत्तिः । तस्मादर्थशब्द इह प्रयोजनवाची तेन योर्थोऽनयोर्द्योत्यस्तस्य प्रकरणादिवशात्संप्रत्ययान्निष्प्रयोजनावेतावुच्येते ॥ धातुनोक्तामिति । प्रकरणादिसामर्थ्यावगतविशेषां धातुनोक्तां क्रियामित्यर्थः ॥ आहतुरिति । द्योतयत इत्यर्थः ॥ तदविशिष्टमिति । तत् क्रियालक्षणं वस्त्वविशिष्टम् । अधिपरिसन्निधानेप्यनाहितविशेषमित्यर्थः ॥ यथेति । शङ्खे न्यस्तं क्षीरं शौक्ल्येनाभिन्नं शङ्खादित्यर्थः ॥

(उद्द्योतः) पूर्वापरितोषेणेति । नेमावनर्थकाविति भाष्येण स्फुटं तदावेदनादिति भावः । किंचोक्तार्थे ज्ञापितेपि न चारितार्थ्यं क्रियागतविशेषद्योतकत्वरूपक्रियायोगाभावेन गतिसंज्ञाद्यप्राप्तेरिति बोध्यम् ॥ प्रयोगानुपपत्तिरिति । तस्माद् द्योत्यार्थेनार्थवत्त्वमस्याप्येषितव्यमित्यर्थः ॥ नन्वेवमनर्थकावित्यसङ्गतमत आह—तस्मादिति । अर्थान्तरबोधकत्वाभावान्निष्प्रयोजनावित्यर्थः ॥ ननु धातुना क्रियोक्तावपि तद्गतोपरिभावसर्वतोभावरूपविशेषद्योतनमनयोः फलमत आह—प्रकरणेति ॥ पूर्वं क्रियाप्रक्रमेण तदिति नपुंसकमनुपपन्नमत आह—तदिति । एवं च क्रियायोगसत्त्वात्प्राप्तगत्यादिसंज्ञाबाधनार्थमिदमावश्यकमिति भावः ॥

(आक्षेपभाष्यम्)

यद्येवं धातुनोक्तत्वात्तस्यार्थस्योपसर्गप्रयोगो न प्राप्नोति "उक्तार्थानामप्रयोगः" इति ॥

(प्रदीपः) यद्येवमिति । धातोर्वाचकत्वात्तस्य प्रयोगं नाक्षिपति तेन विना तयोः प्रयोगासंभवाद् । उपसर्गग्रहणं चाधिपर्योरुपलक्षणार्थम् ॥

(उद्द्योतः) ननु विपरीतं कुतो न शङ्कितमत आह—धातोरिति । धातोः प्रयोगं व्यर्थत्वेन नाक्षिपतीत्यर्थः ॥ तदेवाह—तेन विनेति । तयोर्वाचकत्वाभावादित्यर्थः ॥ नन्वनयोरुपसर्गत्वाभावादुपसर्गेत्यनुपपन्नमत आह—उपसर्गेति ॥

(समाधानभाष्यम्)

उक्तार्थानामपि प्रयोगो दृश्यते । तद्यथा—अपूपौ द्वावानय ब्राह्मणौ द्वावानयेति ॥ अधिपरी९२

(प्रदीपः) उक्तार्थानामपीति । प्रकरणादिवशादवगतार्थानामपि स्फुटतरावगत्यर्थः प्रयोगो लोके भवति । न चानियमप्रसङ्गः । येषामेव हि गतार्थानां प्रयोगो दृश्यते त एव प्रयुज्यन्ते, न तु वृक्षस्तरुः पादप इति तथा प्रयोगादर्शनात् ॥ अपूपौ द्वाविति । अपूपावित्यत एवावगते द्वित्वे द्विशब्दस्यापि प्रयोगो लोके दृश्यते । एतदुक्तं भवति—यथा यावशब्दो वाक्यान्तरविषयोऽन्य एव । अन्यश्च यावकशब्दः । यथा च ऋषभशब्दो वृषभशब्द इति च । तथैवागच्छत्यध्यागच्छति पर्यागच्छतीति च । तदत्र विषये धातोरधिपर्योश्च सहाभिधायित्वमङ्गीकर्तव्यम् ॥ ९२ ॥

(उद्द्योतः) आगच्छत्यध्यागच्छतीत्यादि पाठः । अत्रेदं बोध्यम्—कैयटोक्तयावयावकदृष्टान्तेन भाष्योक्तेनापूपौ द्वाविति दृष्टान्तेन वाऽऽगच्छतीत्यर्थापेक्षयाऽधिकोर्थो नानयोर्द्योत्यो नापि प्रकरणादिनाप्यागच्छतीत्यस्योपरिभावसर्वतोभावार्थकत्वं, किं त्वागमनमात्रार्थकत्वमेवाध्यागच्छतीत्याद्यप्यागमनमात्रार्थकमेव । किं तु बोद्धुस्ततो मिलितादेवार्थबोधेन तस्याप्यनुवादकत्वेन धात्वर्थद्योतकतेति व्यवहारः । फलं तु न किंचिदिति तत्त्वम् ॥ एतेन प्रकरणादिसामर्थ्यावगतविशेषामित्यादिकैयटश्चिन्त्यः सर्वत्र प्रकरणसत्त्वे तद्विषये एव वैतत्प्रयोगे मानाभावाच्च ॥ अपूपौ द्वाविति । अत्र द्विशब्दापूपशब्दयोर्वाचकयोः, प्रत्यययोर्द्योतकयोः, प्रकृतिप्रत्यययोर्वाचकद्योतकयोर्द्वावित्यत्र तयोर्वाचकानुवादकयोश्च समुच्चयो दृश्यत इत्यर्थः ॥ ९३ ॥

(२११ कर्मप्रवचनीयसंज्ञासूत्रम् ॥ १।४।४ आ. १६ सू.)

३३५ अपिः पदार्थसंभावनान्ववसर्गगर्हासमुच्चयेषु ॥ १ । ४ । ९५ ॥

(द्वितीयावारणाधिकरणम्)

(आक्षेपभाष्यम्)

इह कस्मान्न भवति—सर्पिषोपि स्यात् गोमूत्रस्यापि स्यात् ? ॥ किं च स्यात् ? । द्वितीया प्रसज्येत "कर्मप्रवचनीययुक्ते द्वितीया" इति ॥

(प्रदीपः) अपिः पदार्थ ॥ ९५ ॥ इहेति । यथाऽपिशब्दस्य कर्मप्रवचनीयसंज्ञायां सत्यां स्यादित्यत्रोपसर्गाश्रयं षत्वं न भवत्येवं सर्पिःशब्दाद्द्वितीया कस्मान्न भवतीति प्रश्नः ॥ इतरो भवत्येवात्रापेः संज्ञेत्याह—किं च स्यादिति ॥

(उद्द्योतः) अपिः पदार्थ ॥ ९५ ॥ ननूपसर्गत्वप्रयुक्तषत्वस्य स्यादित्यत्र निवृत्तये एतत्संज्ञाप्रवृत्तिरस्त्येवेत्यत आह—यथेति ॥ इत्याहेति । इत्याशयेनाहेत्यर्थः ॥

(आक्षेपबाधकभाष्यम्)

नैष दोषः । नेमे अप्यर्था निर्दिश्यन्ते ॥ किं तर्हि ? । परपदार्था इमे निर्दिश्यन्ते—एतेष्वर्थेषु यत्पदं वर्तते तत्प्रति अपिः कर्मप्रवचनीयसंज्ञो भवतीति ॥

(प्रदीपः) **नेमे इति**। यद्यपिशब्दार्था इमे निर्दिश्येरन्, पदार्थग्रहणमनर्थकं स्यात्। स्वपदार्थाव्यभिचारात्। संभावनादीनां चोपादानमनर्थकं स्यात् तेषामपि पदार्थत्वात्॥ **परपदार्था इति**। स्यादित्यादेः परस्य पदस्यामी अर्था इत्यर्थः। तदयमर्थः—**स्यादित्यादिपदं** कर्तृसामान्यवाच्यपि यदा सामर्थ्यात्कर्तृविशेषे विन्दौ वर्तते तदा तत्प्रत्यपिः कर्मप्रवचनीयः। सर्पिःशब्दस्तु समुदाय एव वर्तते नावयवे। अत एवावयवोपजनितव्यतिरेके षष्ठी भवति॥

(उद्द्योतः) **यद्यपीति**। यदि अपिशब्दार्था इति च्छेदः॥ **स्वपदार्थेति**। स्वपदार्थेन पदस्याव्यभिचारादित्यर्थः॥ **संभावनादीनां चेति**। तेषामप्यपिरूपस्वपदार्थत्वादिति भावः। एषु वर्तमानोऽपिरिति नार्थस्तथासति प्रत्यासत्त्या पदार्थशब्देनापेः स्वपदार्थ एव गृह्येतेति तद्वैयर्थ्यम्। अपिः कर्मप्रवचनीय इत्येव वदेदिति तात्पर्यम्॥ **यदा सामर्थ्यादिति**। अपिशब्दसामर्थ्यादित्यर्थः। अयं भावः—कर्मप्रवचनीययुक्तत्वं तद्द्योत्यसंवन्धप्रतियोगित्वमिव तद्द्योत्यबोधकत्वमपि तच्च स्यादित्यस्यैव न सर्पिष इति न ततो द्वितीया। कर्मप्रवचनीयानां संवन्धद्योतकत्वं तु प्रायिकमधिपर्यादौ व्यभिचारादिति॥ स्यादित्याख्यातेन विन्दुत्वेनाश्रयत्वेन वाश्रयबोध इत्येतत्पक्षतात्पर्यम्॥

(समाधानान्तरभाष्यम्)

अथ वा यदत्र कर्मप्रवचनीययुक्तं नादः प्रयुज्यते। किं पुनस्तत्?। विन्दुः॥ विन्दोस्तर्हि कस्मान्न भवति?। "उपपदविभक्तेः कारकविभक्तिर्बलीयसी" इति प्रथमा भविष्यति॥ अपिः पदार्थ०॥ ९५॥

(प्रदीपः) **अथ वेति**। विन्दुकर्तृकत्वं क्रियायाः द्योतयितुमपिः प्रयुज्यते इति विन्दुं प्रति कर्मप्रवचनीयोऽपिः न तु सर्पिः प्रतीति भावः॥ **विन्दोस्तर्हीति**। ननु यदा विन्दुशब्दो न प्रयुज्यते तदापिः कर्मप्रवचनीयः। तदुच्यते वृत्तिकारैः—पदान्तरस्याप्रयुज्यमानस्यार्थः पदार्थ इति। न चाप्रयुक्ते द्वितीया विधातुं शक्या॥ अत्राहुः—पदार्थग्रहणमिहोपलक्षणार्थमुपात्तं तेन यस्मिन् पदार्थे पदान्तरस्याभिधानशक्तिर्नास्ति तत्रापिः कर्मप्रवचनीयः। ततश्च गतार्थो विन्दुशब्दो यदा विस्पष्टप्रतिपत्तये प्रयुज्यते तदाप्यपिः कर्मप्रवचनीयसंज्ञो भवति॥ **उपपदविभक्तेरिति**। कारकविभक्तिरत्र प्रथमा। सर्वत्रैव वाक्येऽवश्यभाव्यं क्रिययाऽन्ततः सत्तया। तत्र विन्दोः प्रथमं स्यादित्यनेन संबन्धोन्तरङ्गः, पश्चात्तु तद्वारकोऽपिशब्देन॥ ९५॥

(उद्द्योतः) भाष्ये—**अथवेति**। अयं भावः—अपिना परपदार्थो विन्दुस्तद्दौर्लभ्यप्रयुक्तदौर्लभ्यं संवन्धश्च द्योत्यते। तत्रापिद्योत्यसंवन्धप्रतियोगित्वस्य विन्दौ सत्त्वात्तस्यैव कर्मप्रवचनीययुक्तत्वमिति। तदाह—**विन्दुकर्तृकत्वमिति**। तद्दौर्लभ्यप्रयुक्तदौर्लभ्यं चेत्यपि बोध्यम्॥ पृथग्विन्दूपस्थितिस्तस्य चाख्यातार्थेऽभेदान्वय इत्येतत्पक्षतात्पर्यम्॥ **यदत्र कर्मप्रवचनीययुक्तं** कर्मप्रवचनीयद्योत्यसंवन्धप्रतियोगीति भाष्याक्षरार्थः॥ **उपलक्षणार्थमिति**। यत्पदप्रयोगं विनापि तदर्थोऽपिशब्देनावश्यं द्योत्यते तादृशापेः कर्मप्रवचनीयत्वमित्यर्थस्तत्फलितमाह—**तेन यस्मिन्निति**। **पदान्तरस्य** तद्वाचकत्वेन प्रसिद्धातिरिक्तस्य **अभिधानशक्तिर्नास्ति** अपिशब्दसमभिव्याहारं विनेति शेषः। अर्थात्तत्समभिव्याहारेस्तीति लब्धम्। एवं च सर्पिष इत्येतत्तत्संबन्धिविन्दुपरं बोध्यम्। वागादिशब्दे स्त्रीत्वस्य प्रकृतिवाच्यत्वेपि द्योतकटावादिप्रयोगवत् तस्य द्योतकत्ववच्च विन्दुशब्दप्रयोगेप्यपेस्तद्द्योतकत्वाक्षतिरित्याह—**ततश्चेति**॥ ननु प्रथमायाः कारकाधिकारेऽपठितत्वात्कथं कारकविभक्तित्वमत आह—**सर्वत्रैवेति**। क्रियाजनकार्थकत्वमेव कारकविभक्तित्वमिति भावः॥ **अन्तरङ्ग इति**। अपिद्योत्यो विन्दुरिति तस्य कथमपि संवन्धो बहिरङ्ग इति चिन्त्यम्॥ अपिना द्योत्यद्योतकभावः संबन्धः स्वाभाविक इति तस्य कथं स्यादित्येतत्संवन्धोत्तरकालिकता तस्माद्वाचनिकोऽयं न्याय इति तत्त्वम्॥ ९५॥

(२१२ कर्मप्रवचनीयसंज्ञासूत्रम् ॥१।४।४ आ. १७ सू.)

३३६ अधिरीश्वरे ॥ १ । ४ । ९६ ॥

(स्वं प्रति कर्मप्रवचनीयतासाधनाधिकरणम्)

(११६० वार्तिकम् ॥ १ ॥)

॥ * ॥ अधिरीश्वरवचने उक्तम् ॥ * ॥

(भाष्यम्) **किमुक्तम्?। *यस्य चेश्वरवचनमिति कर्तृनिर्देशश्चेदवचनात्सिद्धम्*। *प्रथमानुपपत्तिस्तु*। *स्ववचनात्तु सिद्धम्* इति। अधिः स्वं प्रति कर्मवचनीयसंज्ञो भवतीति वक्तव्यम्॥ अधिरीश्वरे॥ ९६॥**

(प्रदीपः) **अधि॥ ९६॥ उक्तमिति**। वक्ष्यमाणमपि बुद्ध्या निरूपितत्वादुक्तमित्युक्तम्॥ **कर्तृनिर्देशश्चेदिति**। यदीश्वरवचनमित्यनेन पदेनेश्वरः स्वामी भृत्यनियोगादौ यः कर्ता स निर्दिश्यते तदानेन स्वामिनः सप्तमी विधीयते—अधि ब्रह्मदत्ते पञ्चाला इति। तत्राधिकरणत्वादेव सप्तमी सिद्धा। ब्रह्मदत्ते स्थिताः पञ्चाला इत्यर्थावगमात्॥ पञ्चाला इति च प्रथमा न प्राप्नोति **कर्मप्रवचनीययुक्ते द्वितीयेति** द्वितीयया बाधितत्वात्॥ **स्ववचनादिति**। अधिब्रह्मदत्ते पञ्चाला इत्यस्याऽन्यथासिद्धत्वादधिः स्वे इति वक्तव्यम् अधि पञ्चालेषु

ब्रह्मदत्त इत्यर्थम्। ईश्वरवचनमिति च कर्तृषष्ठ्या समासः। ईश्वरेण यदुच्यते स्वं तत्र कर्मप्रवचनीययुक्ते सप्तमीति। यदि वा यस्य संबन्धिन ईश्वरस्य वचनं सप्तमी। तत्र पञ्चालेष्वासनादिक्रियोपजनिते संबन्धे षष्ठ्यां प्राप्तायां सप्तमी विधीयते। स्वं च प्रत्यधेः कर्मप्रवचनीयसंज्ञा न तु स्वामिनमिति स्वामिनः प्रथमैव भवति ॥ ९६ ॥

(उद्द्योतः) अधिरी ॥ ९६ ॥ वक्ष्यमाणमपीति। यस्मादधिकं यस्य चेश्वरवचनमिति सूत्रे इत्यर्थः॥ स निर्दिश्यते इति। यन्निष्ठमीश्वरत्वमुच्यते इत्यर्थादिति भावः॥ प्रथमा न प्राप्नोतीति। सूत्रे ईश्वरेणेशितव्यस्याक्षेपात् तं प्रत्यपि कर्मप्रवचनीयत्वादिति भावः॥ ईश्वरेण यदुच्यते इति। संबध्यत इत्यर्थः। ईश्वरेण स्वनिरूप्यधर्मवत्तया यदुच्यत इत्यर्थो वा। निरूपकस्यैव कर्तृत्वविवक्षा न त्वीशितव्यस्य॥ देशरूपत्वेन पञ्चालानामप्याधारत्वेन सप्तमी सिद्धेत्यत आह—तत्रेति। आसनादिक्रियोपजनितः संबन्धः स्वस्वामिभावादिः॥ ननु ब्रह्मदत्तादपि द्वितीयापत्तिरत आह—स्वं चेति। तस्यैव कर्मप्रवचनीययोत्यसंबन्धप्रतियोगित्वेन ब्रह्मदत्तान्न द्वितीयेति भावः॥ ९६ ॥

(इति कर्मप्रवचनीयसंज्ञाप्रकरणम्)

(इति निपातसंज्ञाप्रकरणम्)

(अथ परस्मैपदात्मनेपदसंज्ञासूत्रे)

(२१३ परस्मैपदसंज्ञासूत्रम् ॥ १। ४। ४ आ. १८ सू.)

३३८ लः परस्मैपदम् ॥ १।४।९८ ॥

(प्रदीपः) लः परस्मैपदम् ॥ ९८ ॥ लः इत्यादेशापेक्षा षष्ठी। लादेशाः परस्मैपदसंज्ञा इत्यर्थः॥

(उद्द्योतः) लः पर ॥ ९८ ॥ नन्वस्य प्रथमान्तत्वे लकाराणामेव परस्मैपदसंज्ञा स्यात् तथा चानुदात्तङित्त्वो लकारा एव न स्युः। किं च तङानावित्यत्र प्रथमान्तस्य संबन्धो न प्राप्नोत्यत आह—षष्ठीति। अत एव टित आत्मनेपदानामित्यादि चरितार्थम्। तङानावित्यादेश्च तङानभाविनि लक्षणायां गौरवमतः षष्ठ्यन्तत्वमेवादेशापेक्षया युक्तमिति भावः॥

(परस्मैपदात्मनेपदसंज्ञयोःपुरुषसंज्ञाभिः-
समावेशाधिकरणम्)

(११६१ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ लादेशे परस्मैपदग्रहणं पुरुषबाधितत्वात् [दिह वचने हि संज्ञाबाधनम्] ॥ * ॥

(भाष्यम्) लादेशे परस्मैपदग्रहणं कर्तव्यम्। किं कारणम्?। पुरुषबाधितत्वात्, इह वचने हि संज्ञाबाधनम्। इह हि क्रियमाणे अनवकाशा पुरुषसंज्ञा परस्मैपदसंज्ञां बाधेत ॥

(प्रदीपः) लादेश इति। लस्येत्यत्र परस्मैपदमिति वक्तव्यम्। इह तु वचने एकसंज्ञाधिकारात्परस्मैपदसंज्ञां शतृक्वसोः सावकाशां पुरुषसंज्ञास्तिङ्क्षु बाधेरन्नित्यर्थः॥

(उद्द्योतः) लस्येत्यत्रेति। लस्य तिप्तस्झीत्यत्रेति भावः। भाष्ये—लादेश इत्यस्य लादेशप्रकरणे इत्यर्थः॥

(आक्षेपबाधकभाष्यम्)

परस्मैपदसंज्ञाप्यनवकाशा सा वचनाद्भविष्यति।

(आक्षेपसाधकभाष्यम्)

सावकाशा परस्मैपदसंज्ञा। कोवकाशः?। शतृक्वसू अवकाशः॥

(११६२ समाधानवार्तिकम् ॥ २ ॥)

॥ * ॥ सिचि वृद्धौ तु परस्मैपदग्रहणं ज्ञापकं पुरुषाबाधकत्वस्य ॥ * ॥

(भाष्यम्) यदयं "सिचिवृद्धिः परस्मैपदेषु" इति परस्मैपदग्रहणं करोति तज्ज्ञापयत्याचार्यः 'न पुरुषसंज्ञा परस्मैपदसंज्ञां बाधते' इति॥ लः परस्मै०॥९८

(प्रदीपः) सिचि वृद्धौ त्विति। अस्मादेव लिङ्गादेकसंज्ञाधिकारोऽत्र बाध्यत इति भावः। आत्मनेपदसंज्ञया परस्मैपदसंज्ञाया बाधनं यथा स्यादित्येवमर्थं त्विह प्रकरणेऽनयोः संज्ञयोर्विधानम्। सामान्यापेक्षं च ज्ञापकमित्यात्मनेपदसंज्ञयापि पुरुषसंज्ञानां समावेशो भवति। अन्यथा पुरुषसंज्ञाः सावकाशास्तङ्क्षु अनवकाशया आत्मनेपदसंज्ञया बाध्येरन्॥ ९८ ॥

(उद्द्योतः) बाध्यत इति। इष्टानुरोधादिति भावः॥ एतेन पर्यायज्ञापनेनापीदं चरितार्थमित्यपास्तम्॥ ननु तृतीय एव परस्मैपदसंज्ञाऽस्तु किं ज्ञापकाश्रयणेनेत्यत आह—आत्मनेपदेति॥ ननु ज्ञापकात्परस्मैपदसंज्ञया समावेशेप्यात्मनेपदसंज्ञया पुरुषसंज्ञानां समावेशो न स्यादत आह—सामान्यापेक्षं चेति। पुरुषसंज्ञायां परस्मैपदात्मनेपदग्रहणानुवृत्त्या समावेशसिद्धिः। अनुवृत्तिरेव लिङ्गेन विवक्षिता। एतदर्थमेव चात्र प्रकरणे पुरुषसंज्ञादिविधानमित्यन्ये॥ ९८ ॥

(अथ प्रथममध्यमोत्तमपुरुषसंज्ञासूत्रम्)

(२१४ प्रथममध्यमोत्तमसंज्ञासूत्रम् ॥ १। ४ ।७ आ. १९ सू.)

३४० तिङस्त्रीणित्रीणि प्रथममध्यमोत्तमाः ॥ १ । ४ । १०० ॥

(यथासंख्योपपादनाधिकरणम्)

(११६३ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ प्रथममध्यमोत्तमसंज्ञायामात्मनेपदग्रहणं समसंख्यार्थम् ॥ * ॥

(भाष्यम्) प्रथममध्यमोत्तमसंज्ञायामात्मनेपदग्रहणं कर्तव्यम् । आत्मनेपदानां च प्रथममध्यमोत्तमसंज्ञा भवन्तीति वक्तव्यम् ॥ किं प्रयोजनम् ? । समसंख्यार्थम् । संख्यातानुदेशो यथा स्यात् । अक्रियमाणे ह्यात्मनेपदग्रहणे तिस्रः संज्ञाः, षट् संज्ञिनः, वैषम्यात्संख्यातानुदेशो न स्यात् ॥

(प्रदीपः) तिङस्त्रीणि ॥ १०० ॥ तिङां षट् त्रिकाः संज्ञास्तिस्र इति वैषम्याद्यथासंख्यं न प्राप्नोतीति मत्वाह— प्रथमेति । आत्मनेपदग्रहणे च पृथक् क्रियमाणे सूत्रं परस्मैपदविषयमेव भवतीति वाक्यभेदादेकेन वाक्येन परस्मैपदानां त्रयाणां तिस्रः संज्ञा द्वितीयेनात्मनेपदानामिति सिद्धमिष्टम् ॥ वैषम्यादिति । यद्यप्येकैकस्य त्रिकस्यानेकसंज्ञाकरणे प्रयोजनाभावः तथापि कस्यचित्त्रिकस्य काचित्संज्ञेत्येतावल्लभ्येत न तु यथाभिमतविषयविभागलाभः ॥

(उद्द्योतः) तिङस्त्रीणि ॥ १०० ॥ ननु तिङस्त्रीणि त्रीणीत्यनेनात्मनेपदत्रिकाणामपि ग्रहणं सिध्यतीत्यत आह— तिङां षडिति ॥ नन्वात्मनेपदग्रहणे कृते परस्मैपदसंबन्धिनां संज्ञा न स्यादिति दोषस्तदवस्थ एवेत्यत आह—आत्मनेपदेति ॥

(भाष्यम्) क्रियमाणेपि चात्मनेपदग्रहणे—॥

(११६४ आक्षेपान्तरवार्तिकम् ॥ २ ॥)

॥ * ॥ आनुपूर्व्यवचनं च ॥ * ॥

(भाष्यम्) आनुपूर्व्यवचनं च कर्तव्यम् । अक्रियमाणे हि कस्यचिदेव त्रिकस्य प्रथमसंज्ञा स्यात् कस्यचिदेव मध्यमसंज्ञा कस्यचिदेवोत्तमसंज्ञा ॥

(प्रदीपः) आनुपूर्व्यवचनं चेति । अत्र सूत्रे त्रिकाणामुच्चारणं नास्ति, केवलं त्रीणित्रीणीति वीप्सया प्रतिपत्तिस्तेषाम् । तत्रानियमप्रसङ्गे नियमार्थमानुपूर्व्यग्रहणं च कर्तव्यमित्यर्थः ॥

(११६५ परिहारवार्तिकम् ॥ ३ ॥)

॥ * ॥ नवैकशेषनिर्देशात् ॥ * ॥

(भाष्यम्) यत्तावदुच्यते—*आत्मनेपदग्रहणं कर्तव्यं समसंख्यार्थम्* इति, तन्न कर्तव्यम् । संज्ञा अपि षडेव निर्दिश्यन्ते । कथम् ? । एकशेषनिर्देशात् । एकशेषनिर्देशोयम् ॥

(प्रदीपः) एकशेषनिर्देशादिति । आकृत्यभिधानाश्रयेण प्रत्याख्यातं सूत्रं शास्त्रप्रक्रियासंपत्त्यर्थमेव संपद्यते ॥

(उद्द्योतः) सहविवक्षाभावादेकशेषो न प्राप्नोतीत्यत आह— आकृतीति । इदमुपलक्षणं, व्यक्तिपक्षेपि तत्प्रत्याख्यानात् । यद्वैकशेषशब्देन तन्त्रं लक्ष्यते ॥

(कृतद्वन्द्वानामेकशेषसाधनाधिकरणम्)

(आक्षेपभाष्यम्)

अथैतस्मिन्नेकशेषनिर्देशे सति किमयं कृतैकशेषाणां द्वन्द्वः—प्रथमश्च प्रथमश्च प्रथमौ । मध्यमश्च मध्यमश्च मध्यमौ । उत्तमश्चोत्तमश्चोत्तमौ । प्रथमौ च मध्यमौ च उत्तमौ च प्रथममध्यमोत्तमा इति ॥ आहोस्वित्कृतद्वन्द्वानामेकशेषः—प्रथमश्च मध्यमश्चोत्तमश्च प्रथममध्यमोत्तमाः प्रथममध्यमोत्तमाश्च प्रथममध्यमोत्तमाश्च प्रथममध्यमोत्तमा इति ॥

(प्रदीपः) अथैतस्मिन्निति । उभयथा संभवात्प्रश्नः ॥

(विशेषजिज्ञासाभाष्यम्)

किं चातः ? ॥

(विशेषदर्शकभाष्यम्)

यदि कृतैकशेषाणां द्वन्द्वः; प्रथममध्यमयोः प्रथमसंज्ञा प्राप्नोति । उत्तमप्रथमयोर्मध्यमसंज्ञा प्राप्नोति । मध्यमोत्तमयोरुत्तमसंज्ञा प्राप्नोति ॥ अथ कृतद्वन्द्वानामेकशेषः, न दोषो भवति ॥

(प्रदीपः) प्रथममध्यमयोरिति । प्रसिद्धिमाश्रित्यैतदुच्यते ॥ व्याख्यानान्निर्णय इति मत्वाह—कृतद्वन्द्वानामिति ॥

(उद्द्योतः) नन्वेतत्संज्ञाप्रवृत्तेः पूर्वं प्रथममध्यमयोरिति व्यवहारो न युक्तोऽत आह—प्रसिद्धिमिति । सिद्धान्तकालिकीं प्रसिद्धिमित्यर्थः ॥

(सिद्धान्तिभाष्यम्)

यथा न दोषस्तथास्तु ॥

(आक्षेपभाष्यम्)

किं पुनरत्र न्याय्यम् ? ॥

(उद्द्योतः) भाष्ये किं पुनरत्रेति । यद्यप्यत्र व्याख्यानतः कृतद्वन्द्वानामेवैकशेषस्तथापि लोके कथं न्याय्यमिति प्रश्नः ॥

(समाधानभाष्यम्)

उभयमित्याह । उभयं हि दृश्यते । तद्यथा— बहु शक्तिकिटकम्, बहूनि शक्तिकिटकानि । बहु स्थालीपिठरम्, बहूनि स्थालीपिठराणि ॥

(प्रदीपः) **बहुशक्तिकिटकमिति** । एकशेषे कृते द्वन्द्वः । **जातिरप्राणिनामि**त्येकवद्भावः । बहुशब्दश्चात्र वैपुल्यवचन इत्येकवचनम् । समुदायस्य वैपुल्यमवयवानां प्रचयाद्भवति । यदा तु समाहारद्वन्द्वे कृते एकशेषः क्रियते तदा बहूनि शक्तिकिटकानीति भवति ॥

(उद्द्योतः) नन्वस्य बहुशब्दस्य बहुत्वार्थकत्वे एकवचनानुपपत्तिरत आह—**बहुशब्दश्चेति** ॥ नन्वेवमवयवबहुत्वप्रतीतिर्न स्यादत आह—**समुदायस्येति** ॥

(द्वितीयाक्षेपपरिहारभाष्यम्)

यदप्युच्यते—क्रियमाणेप्यात्मनेपदग्रहणे * आनुपूर्व्यवचनं कर्तव्यमिति । न कर्तव्यम् । लोकत एतत्सिद्धम् । तद्यथा लोके "विहव्यस्य द्वाभ्यां द्वाभ्यामग्निरुपस्थेय"इति । न चोच्यते—आनुपूर्व्येणेति । आनुपूर्व्येण चोपस्थीयत इति ॥ तिङ्स्त्रीणि ॥ १०० ॥

(प्रदीपः) **लोकत इति** । यथा पङ्क्तिस्थेषु ब्राह्मणेषु द्वौद्वौ ब्राह्मणावानयेत्युक्ते आनुपूर्व्येणानयनं भवति न तु व्युत्क्रमेण तथेहापि भवतीत्यर्थः ॥ **विहव्यस्येति** । विहव्याख्यस्य सूक्तस्य द्वाभ्यां द्वाभ्यामग्निरुपस्थेय इत्युक्ते आनुपूर्व्येण ऋग्द्वयं गृह्यते न तु व्युत्क्रमेण ॥ १०० ॥

(उद्द्योतः) भाष्ये—**लोकत इति** । विहव्यस्येत्यादिस्मृतेरित्यर्थः ॥ **तथेहापीति** । प्रथममध्यमेत्यादि महासंज्ञाकरणं तु प्राचामनुरोधेनैवेति भावः ॥ **"ममाग्ने वर्च विहव्य"** इति सर्वानुक्रमः ॥ १०० ॥

(अथ तिङ्सुपोर्विभक्तिसंज्ञासूत्रम्)

(२१५ विभक्तिसंज्ञासूत्रम् ॥१।४।४ आ. २० सू.)

३४३ विभक्तिश्च ॥ १ । ४ । १०३ ॥

(आक्षेपभाष्यम्)

त्रीणित्रीणीत्यनुवर्तते, उताहो न? ॥

(प्रदीपः) **विभक्तिश्च ॥ १०३ ॥** सति प्रयोजने स्वरितत्वप्रतिबद्धे शब्दानामनुवृत्त्यननुवृत्ती भवतः । लिङ्गदर्शनं न पक्षद्वयेप्यस्ति इति संदेहात्प्रश्नः—**त्रीणित्रीणीति** ॥

(उद्द्योतः) विभक्तिश्च ॥ १०३ ॥ अननुवृत्तौ स्वरितत्वप्रतिबद्धत्वमभावप्रतियोगितया बोध्यम् । स्वरितत्वमस्ति नवेति विचारतात्पर्यम् । स्वरितत्वमाचार्याणामप्यनुमेयमेवेति बोध्यम् ॥

(आक्षेपबीजप्रश्नभाष्यम्)

किं चातः? ।

(प्रथमपक्षदूषणभाष्यम्)

यद्यनुवर्तते,—"अष्टन आ विभक्तौ" इत्यात्वं न प्राप्नोति ॥

(प्रदीपः) **आत्वं न प्राप्नोतीति** । नह्यष्टन्शब्दात्परं युगपत्त्रिकमस्ति ॥

(द्वितीयपक्षदूषणभाष्यम्)

अथ निवृत्तम्, "प्रथमयोः पूर्वसवर्णः" इत्यत्र प्रत्यययोरेव ग्रहणं प्राप्नोति ॥

(प्रदीपः) **प्रथमयोरिति** । प्रत्येकं संज्ञित्वे विभक्तिसमुदायस्य विभक्तिग्रहणेनाग्रहणात्**प्रथमयो**रिति समुदायद्वयापेक्षानुपपत्तौ प्रत्यययोरेव द्वयोर्ग्रहणं प्राप्नोतीत्यर्थः ॥

(उद्द्योतः) **प्रत्येकमिति** । नन्वस्याः प्रत्येकं सत्त्वेपि द्वितीयायां चेत्यादिव्यवहारात् त्रिकस्य त्रिकस्य प्रथमादयः सप्त संज्ञा अवश्यमभ्युपेयाः । एवं च तया **प्रथमयो**रित्यत्राप्युपपत्तिरिति चेन्न । पाणिनिना तासामकृतत्वात् । सिद्धान्ते तु त्रिकस्य विभक्तित्वेऽवयवधर्मविभक्तित्वस्य त्रिके आरोपे वा यौगिका एव ते व्यवहाराः संभवन्तीति ताः संज्ञाः सूत्रकृता न कृता इति प्रतीमः ॥ **विभक्तिसमुदायस्येति** । जनपदसमुदायस्य जनपदग्रहणेनाग्रहणवदिति भावः ॥ **समुदायद्वयापेक्षानुपपत्ताविति** । तदपेक्षद्विवचनानुपपत्तावित्यर्थः ॥

(सिद्धान्तिभाष्यम्)

यथेच्छसि तथास्तु ॥

(प्रथमपक्षाभ्युपगमभाष्यम्)

अस्तु तावद्—अनुवर्तत इति ॥

(आक्षेपस्मारणभाष्यम्)

ननु चोक्तम्—"अष्टन आ विभक्तौ" इत्यात्वं न प्राप्नोतीति ॥

(आक्षेपपरिहारभाष्यम्)

वचनाद्भविष्यति ॥

(प्रदीपः) **वचनादिति** । त्रिकस्य युगपत्प्रयोगाभावात्सामर्थ्यात्समुदायवृत्तिर्विभक्तिशब्दोऽवयवे वर्तिष्यत इति भावः ॥

(द्वितीयपक्षाभ्युपगमभाष्यम्)

अथ वा पुनरस्तु—निवृत्तम् ॥

(आक्षेपसारणभाष्यम्)

ननु चोक्तं "प्रथमयोः पूर्वसवर्णः" इति प्रत्यययोरेव ग्रहणं प्राप्नोतीति ॥

(आक्षेपपरिहारभाष्यम्)

नैष दोषः । अचीत्यनुवर्तते । न चाजादी प्रथमौ प्रत्ययौ स्तः ॥

(प्रदीपः) **न चाजादी** इति । सुशब्दौशब्दौ प्रथमौ सुश्चाजादिर्न भवतीति प्रत्यययोरजादित्वासंभवादवयवशब्दस्त्रिके समुदाये उपचाराद्वर्तत इति भावः ॥

(उद्द्योतः) सुशब्दौशब्दाविति । प्रथमावि[मयोरि]ते विशेष्यमचीति विशेषणमिति भावः ॥ **अजादित्वासंभवादिति** । यद्यपि शिवोर्च्य इत्यादावुत्वे कृते सम्भवोऽस्ति तथापि तत्र **नादिचीति** निषेध इति भावः ॥

(आक्षेपभाष्यम्)

ननु चैवं विज्ञायते—अजादी यौ प्रथमौ, अजादीनां वा यौ प्रथमाविति ॥

(प्रदीपः) **अजादी याविति** । अजादी विशेष्यौ प्रथमयोरिति विशेषणं तेनौजसोरेव ग्रहणमस्त्वित्यर्थः ॥ **अजादीनां वेति** । अचीत्यनुवर्तते । तत्र व्याख्यानात्तदादिविधिः । निर्धारणं चाश्रयिष्यते—अजादिषु यौ प्रथमाविति । एवमप्यौजसोरेव ग्रहणं स्यादिति चोद्यम् ॥

(उद्द्योतः) एकदेशी शङ्कते—**ननु चेति** । तद्याचष्टे—**अजादी विशेष्याविति** । व्याख्यानाच्छब्दरूपं विशेष्यमादाय तदादिविधिरिति भावः ॥

(समाधानभाष्यम्)

यत्तर्हि "तस्माच्छसो नः पुंसि" इत्यनुक्रान्तं पूर्वसवर्णं प्रतिनिर्दिशति । तज्ज्ञापयत्याचार्यः—विभक्त्योर्ग्रहणम्—इति ॥

(प्रदीपः) **यत्तर्हीति** । एतान् गाः पश्येत्यत्र नत्वनिवृत्त्यर्थं तस्मादित्युच्यते । औजसोरेव ग्रहणेऽनन्तरात् पूर्वसवर्णदीर्घादुत्तरः शसः सकारो न भवतीति किं तस्मादित्यनेन । तत्क्रियमाणं त्रिकद्वयग्रहणस्य ज्ञापकं संपद्यते ॥ १०३ ॥

(उद्द्योतः) वस्तुतो निर्धारणमेकवचनान्तेन नेति **कारक इति**सूत्रे भाष्ये उक्तम् । शब्दरूपं विशेष्यमादाय तदन्तविधिश्चासति गमके नेतीयं शङ्काऽयुक्तैव तथापि तामुपगम्य पर एकदेशी समाधत्ते—**यत्तर्हीति** ॥ भाष्ये—**विभक्त्योरिति** । विभक्तिसमुदाययोरित्यर्थः । तौ च समुदायौ प्राचां वैयाकरणानां प्रथमाद्वितीयादिसंज्ञत्वेन प्रसिद्धावेव गृह्येते । न च **तस्मादित्य**नेन गा इत्येतद्व्यावृत्तये सवर्णदीर्घ एव परामृष्टव्यः, तस्य व्यवहितत्वादित्याशयः । एतद्भाष्यमूलिका एव प्रथमादयः सप्तम्यन्ताः स्वौजसादीनां सप्तानां त्रिकाणां संज्ञा इति बोध्यम् ॥ १०३ ॥

(ज्ञापकान्तरभाष्यम्)

अथ वा वचनग्रहणमेव कुर्याद् "औजसोः पूर्वसवर्णः" इति ॥ विभक्तिश्च ॥ १०३ ॥

(२१६–२१८ नियमसूत्राणि ॥ १।४।४ आ. २१–२३ सू.)

३४४, ३४६–३४७ युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः ॥१०४॥ अस्मद्युत्तमः ॥१०६॥ शेषे प्रथमः ॥ १०७ ॥

(सूत्रप्रयोजनाधिकरणम्)

(आक्षेपभाष्यम्)

किमर्थमिदमुच्यते ? ॥

(प्रदीपः) **युष्म** ॥१०४॥ **किमर्थमिति** । किं लादेशविधानवाक्यैनैकवाक्यत्वाद्विध्यर्थमिदम् । अथ विहितेषु लादेशेषु नियमार्थमिदमिति प्रश्नः ॥

(११६६ समाधानवार्तिकम् ॥ १ ॥)

॥*॥ युष्मदस्मच्छेषवचनं नियमार्थम् ॥*॥

(भाष्यम्) **नियमार्थोयमारम्भः ॥**

(प्रदीपः) तत्रैकवाक्यतापक्षे इतरेतराश्रयपरिहाराय भाविनी संज्ञाश्रयितव्येति प्रतिपत्तिलाघवार्थं वाक्यभेदेन नियमपक्षं दर्शयितुमाह—**युष्मदस्मदिति** ।

(उद्द्योतः) **युष्मद्यु** ॥ १०४ ॥ विधिनियमसम्भवे विधेर्ज्यायस्त्वादाह—**तत्रेति** । वस्तुत एकवाक्यतापक्षेपि फलतो नियमत्वमेवैतैर्विनापि सिद्धेः । **शुद्धविध्यर्थमिति** पूर्वपक्षः । अन्यथापि सिद्धेरितरनिवृत्त्यर्थमिति सिद्धान्त इति तत्त्वम् ॥

(आक्षेपभाष्यम्)

अथैतस्मिन्नियमार्थे विज्ञायमाने किमयमुपपदनियमः—युष्मदि मध्यम एव, अस्मद्युत्तम एव । आहोस्वित्पुरुषनियमः—युष्मद्येव मध्यमः, अस्मद्येवोत्तम इति ? ॥

(प्रदीपः) **किमयमिति** । ननु प्रत्ययस्य प्राधान्यात्तन्नियम एव युक्तः । नैष दोषः । समुदायस्य संचिस्कीर्षितत्वात् प्राधान्यं तदङ्गत्वात्तु प्रत्ययोपपदयोर्द्वयोरप्यप्राधान्यमित्युभयोरपि नियम आशङ्क्यते ॥ **युष्मदि मध्यम एवेति** । तुल्यजातीयव्यावृत्तेर्नियमफलत्वादुत्तमप्रथमौ निवार्येते न तृजादयः । तृजादिविधिसामर्थ्याद्वा नास्ति तेषां निवारणम् ॥

(उद्द्योतः) **समुदायस्येति** । विधेये शाब्दं प्राधान्यमुद्देश्ये तूद्देश्यतालक्षणमार्थं प्राधान्यमिति संदेहे बीजं वक्तुं युक्तम् ॥ सामान्यनियमेप्याह—**तृजादीति** ॥

(विशेषप्रश्नभाष्यम्)

किं स्यातः ? ॥

(द्वितीयपक्षे गौरवदर्शनभाष्यम्)

यदि पुरुषनियमः शेषग्रहणं कर्तव्यं "शेषे प्रथमः" इति। किं कारणम् ? । मध्यमोत्तमौ नियतौ, युष्मदस्मदी अनियते, तत्र प्रथमोऽपि प्राप्नोति। तत्र शेषग्रहणं कर्तव्यं प्रथमनियमार्थम्—शेष एव प्रथमो भवति नान्यत्रेति ॥

(प्रथमपक्षेपि गौरवदर्शनभाष्यम्)

अथाप्युपपदनियमः, एवमपि शेषग्रहणं कर्तव्यम् "शेषे प्रथमः" इति । युष्मदस्मदी नियते, मध्यमोत्तमावनियतौ, तौ शेषेपि प्राप्नुतः । तत्र शेषग्रहणं कर्तव्यं शेषनियमार्थम्—शेषे प्रथम एव भवति नान्य इति ॥

(प्रथमपक्षे गौरवपरिहारभाष्यम्)

उपपदनियमे शेषग्रहणं शक्यमकर्तुम्। कथम्?। युष्मदस्मदी नियते मध्यमोत्तमावनियतौ तौ शेषेपि प्राप्नुतः। ततो वक्ष्यामि 'प्रथमो भवति' इति। तन्नियमार्थं भविष्यति। यत्र प्रथमश्चान्यश्च प्राप्नोति तत्र प्रथम एव भवतीति ॥

(प्रदीपः) **यत्र प्रथमश्चेति**। युष्मदि मध्यम एव, अस्मद्युत्तम एवेति युष्मदस्मदोर्नियतत्वात् तयोः पुरुषान्तरं न भवति । मध्यमोत्तमयोस्त्वनियतत्वात् शेषेपि तत्प्रसङ्गे प्रथम इति सूत्रमारभ्यमाणं सिद्धे प्रथमे मध्यमोत्तमयोर्निवारणाय नियमार्थं संपद्यते प्रथम एव भवति न मध्यमोत्तमाविति। यथा समे देशे यजेतेति पाक्षिक्यां प्राप्तौ नियमः ॥

(उद्द्योतः) **सिद्धे प्रथमे इति**। तिबादिसूत्रेण पक्षे सिद्ध इति भावः ॥ **प्रथम एव भवतीति**। नियमान्तरस्यासम्भवादित्यर्थः ॥ **पाक्षिक्यां प्राप्ताविति** । नन्वेवमेतन्नियमापेक्षया पुरुषनियमस्य परिसंख्यात्वेन गुरुतयोपपदनियम एवोचित इति चेन्न । अनुवादत्वस्यैवकारार्थगर्भत्वस्य प्राप्तबाधकल्पनस्य चोभयत्राप्यविशिष्टत्वेन तयोः समत्वमेवेत्याशयात् ॥

(अनिष्टवारणाधिकरणम्)

(११६७ आक्षेपवार्तिकम् ॥ २ ॥)

॥ * ॥ तत्र युष्मदस्मदन्येषु प्रथमस्य प्रतिषेधः शेषत्वात् ॥ * ॥

(भाष्यम्) **तत्र युष्मदस्मदन्येषु प्रथमस्य प्रतिषेधो वक्तव्यः। त्वं च देवदत्तश्च पचथः। अहं च देवदत्तश्च पचावः ॥ किं कारणम्?। शेषत्वात्। "शेषे प्रथमः" इति प्रथमः प्राप्नोति ॥**

(प्रदीपः) **तत्रेति**। उभयथा नियमे इत्यर्थः ॥ **शेषत्वादिति**। यत्र केवले युष्मदस्मदी उपपदे स एवाशेषस्तत्र मा भूत् प्रथमः । यत्र त्वन्यसहिते ते स्तः तत्र समुदायस्य युष्मदस्मद्ग्रहणेनाग्रहणाच्छेषत्वमेवेति प्रथमप्रतिषेधो वक्तव्यः ॥

(उद्द्योतः) नन्वत्र युष्मदस्मदोः सत्त्वात्कथं शेषत्वमत आह—**यत्र केवले इति** । असहाये इत्यर्थः ॥

(११६८ आक्षेपपरिहारवार्तिकम् ॥ ३ ॥)

॥ सिद्धं तु युष्मदस्मदोः प्रतिषेधात् ॥

(भाष्यम्) **सिद्धमेतत्। कथम् ?। युष्मदस्मदोः प्रतिषेधात्। "शेषे प्रथमः" "युष्मदस्मदोर्न" इति वक्तव्यम् ॥**

(प्रदीपः) स एवाह—**सिद्धं त्विति**। यत्र शेषे युष्मदस्मदी स्तस्तत्र शेषे प्रथमो नेति वक्तव्यमित्यर्थः ॥

(उद्द्योतः) **सिद्धं त्वित्युक्तिर्न** सिद्धान्तिनो वचनारम्भस्याश्रापि सत्त्वादत आह—**स एवाहेति** । पूर्वस्य वचनस्य गुरुत्वात्स एव लाघवाश्रयेण सिद्धं त्वित्यादीत्यर्थः ॥ ननु युष्मदस्मदोर्नेत्युक्तेपि यत्र केवले ते तत्रैव निषेधः स्यादत आह—**यत्र शेषे इति** । शेषग्रहणं तत्रानुवर्त्तत इति भावः ॥

(११६९ आक्षेपवार्तिकम् ॥ ४ ॥)

॥ * ॥ युष्मदि मध्यमादस्मद्युत्तमो विप्रतिषेधेन ॥ * ॥

(भाष्यम्) **युष्मदि मध्यमादस्मद्युत्तम इत्येतद्भवति विप्रतिषेधेन "युष्मदि मध्यम" इत्यस्यावकाशः त्वं पचसि। "अस्मद्युत्तम" इत्यस्यावकाशः—अहं पचामि। इहोभयं प्राप्नोति—त्वं चाहं च पचावः। "अस्मद्युत्तमः" इत्येतद्भवति विप्रतिषेधेन ॥**

(तृतीयाक्षेपभाष्यम्)

स तर्हि विप्रतिषेधो वक्तव्यः ? ॥

(प्रदीपः) चोदक आह—**स तर्हीति** ।

(उद्द्योतः) **चोदक इति** । तृतीय इत्यर्थः ॥

(सिद्धान्त्येकदेशिसमाधानभाष्यम्)

न वक्तव्यः। 'त्यदादीनां यद्यत्परं तत्तच्छिष्यते' इत्येवमस्मदः शेषो भविष्यति। तत्र "अस्मद्युत्तमः" इत्येव सिद्धम् ॥

(प्रदीपः) आचार्यदेशीय आह—**न वक्तव्य इति** ॥ **अस्मदः शेष इति** । आवां पचाव इति ॥ **तत्रास्मद्युत्तम इति** । ननु शिष्यमाणस्यास्मदो द्व्यर्थत्वादप्रयुज्यमानेपि युष्मदि तदर्थगतौ मध्यमविधानात् तस्याप्यत्र प्रसङ्ग इति विप्रतिषेध एवाश्रयितव्यः । अत्राहुः—युष्मदर्थे साहचर्याद्यदास्मद्रूपत्वमारोप्यते तदा भेदाभावात् पृथग्युष्मदर्थाभावाद् अस्मदुपपदनिमित्तः सिद्ध उत्तम एवेत्यदोषः ॥

(उद्द्योतः) आरोप्यत इति । तं विना चासच्छब्दात्तद्बोधसंभव इति भावः ॥ तदा पृथगिति । संबोध्यत्वेनावोधादित्यर्थः । तदा भेदाभावात् पृथगिति पाठे तदारोपादेव युष्मदर्थे भेदकधर्माभावाद् भेदकधर्मांप्रतीतेर्हेतोः पृथग्युष्मदर्थाभाव इत्यर्थः ॥

(११७० आक्षेपसाधकवार्तिकम् ॥ ५ ॥)

॥ * ॥ अनेकशेषभावार्थं तु ॥ * ॥

(भाष्यम्) अनेकशेषभावार्थं तु स विप्रतिषेधो वक्तव्यः । यदा चैकशेषो न ॥ कदा चैकशेषो न? । सहविवक्षायामेकशेषः । यदा न सहविवक्षा तदैकशेषो नास्ति ॥

(प्रदीपः) चोदकस्त्वाह—अनेकशेषभावार्थं त्विति त्वं चाहं च पचाव इत्यत्र प्रयोगे ॥

(उद्द्योतः) अत्र प्रयोगे इति । चशब्देनैव साहित्यस्य द्योतनादत्रैकशेषो नेत्यर्थः ॥ भाष्ये यदा न सहविवक्षेत्यस्य चं विना केवलपदैर्यदा न साहित्यबोध इत्यर्थः ॥

(११७१ आक्षेपपरिहारवार्तिकम् ॥ ६ ॥)

॥ * ॥ नवा युष्मदस्मदोरनेकशेषभावात्तदधिकरणानामप्यनेकशेषभावादविप्रतिषेधः ॥ * ॥

(भाष्यम्) नवार्थो विप्रतिषेधेन । किं कारणम्? । युष्मदस्मदोरनेकशेषभावात्तदधिकरणानामपि युष्मदस्मदधिकरणानामपि एकशेषेण न भवितव्यम् । त्वं चाहं च पचसि पचामि चेति ॥

(प्रदीपः) आचार्यदेशीय आह—नवेति । सहविवक्षाया अभावे यथा युष्मदस्मदोरेकशेषाभावः । एवं तदधिकरणयोरपि क्रिययोर्भेदस्य विवक्षितत्वादाख्यातयोरप्येकशेषाभावे पचसि पचामि चेति पृथगेव प्रयोगान्नार्थो विप्रतिषेधेनेत्यर्थः ॥

(उद्द्योतः) तदधिकरणयोरिति षष्ठीबीहिः ॥ भाष्ये तदधिकरणानामिति बहुवचनं त्वनेकयुष्मच्छब्दप्रयोगाभिप्रायेण ॥

(११७२ परिहारसाधकवार्तिकम् ॥ ७ ॥)

॥*॥ क्रियापृथक्त्वे च द्रव्यपृथक्त्वदर्शनमनुमानमुत्तरत्रानेकशेषभावस्य ॥*॥

(भाष्यम्) क्रियापृथक्त्वे च द्रव्यपृथक्त्वं दृश्यते । तद्यथा—पचसि च पचामि च त्वं चाहं चेति । तदनुमानमुत्तरयोरपि क्रिययोरेकशेषो न भवतीति । एवं च कृत्वा सोऽप्यदोषो भवति यदुक्तम्—*तत्र युष्मदस्मदन्येषु प्रतिषेधः शेषत्वाद्* इति । तत्रापि ह्येवं भवितव्यम्—त्वं च देवदत्तश्च पचसि च पचति चेति । अहं च देवदत्तश्च पचामि च पचति चेति ॥

(प्रदीपः) एतदेव समर्थयितुमाह—क्रियापृथक्त्व इति । यथा क्रियापृथक्त्वे सति द्रव्यपृथक्त्वं न तु सहविवक्षा एवं द्रव्यपृथक्त्वेपि क्रियापृथक्त्वेन भाव्यं परस्परसाहचर्यात्यभिचारात् ॥ एवं च कृत्वेति । द्रव्यपृथक्त्वे सति क्रियापृथक्त्वादित्यर्थः ॥

(उद्द्योतः) न तु सहविवक्षेति । न तन्निबन्धन एकशेष इति भावः ॥ एवं द्रव्येति । क्रियापृथक्त्वोपक्रमे वाक्ये यथा द्रव्यपृथक्त्वमेवं द्रव्यपृथक्त्वोपक्रमे क्रियापृथक्त्वमेवेत्यर्थः ॥

(सिद्धान्तिसमाधानभाष्यम्)

यत्तावदुच्यते—*नवा युष्मदस्मदोरनेकशेषभावात्तदधिकरणानामप्यनेकशेषभावादविप्रतिषेधः* इति ॥ दृश्यते हि युष्मदस्मदोश्चानेकशेषस्तदधिकरणानां चैकशेषः । तद्यथा—"त्वं चाहं च वृत्रहन्नुभौ संप्रयुज्यावहै" इति ॥ यदप्युच्यते—*क्रियापृथक्त्वे च द्रव्यपृथक्त्वदर्शनमनुमानमुत्तरत्रानेकशेषभावस्य* इति । क्रियापृथक्त्वे खल्वपि द्रव्यैकशेषो भवतीति दृश्यते । तद्यथा—अक्षाः भज्यन्तां भक्ष्यन्तां दीव्यन्तामिति ॥

(प्रदीपः) इदानीमाचार्य आह—यत्तावदिति । एकशेषफलत्वादेकशेष इत्युच्यते । न तु प्रथममध्यमोत्तमानामेकशेषोऽसरूपत्वादिति वाचनिक एकशेषः । एवं श्लोकशेषे आश्रीयमाणे नार्थो विप्रतिषेधेन । तस्मात्कारकभेदेपि क्रियाया अभेदादेक एव धातुः प्रयुज्यते । तस्माच्च परो लकार एवानेकार्थाभिधायी विरोधाभावात् । तत्र पुरुषद्वयप्रसङ्गे युक्तो विप्रतिषेधः ॥ अक्षा इति । शकटाक्षविभीतकाक्षदेवनाक्षाणां सहविवक्षायामेकशेषः । तत्रावयवक्रियायाः समुदाये आरोपाद्भज्यन्तामित्यादि बहुवचनं सामानाधिकरण्यं चोपपद्यते । यथा द्रव्यैकशेषेपि क्रियापृथक्त्वमेवं द्रव्यपृथक्त्वेपि क्रियैकशेष इत्यर्थः ॥

(उद्द्योतः) न त्विलस्य वाचनिक एकशेष इत्यत्रान्वयः ॥ तदेव वचनमाह—प्रथमेत्यादि । इदं सरूपसूत्रे वार्तिकम् ॥ वाचनिकैकशेषे दूषणमाह—एवं हीति । विप्रतिषेधस्थापनाय चैतद्भाष्यप्रवृत्तिरिति भावः ॥ अथ भाष्याशयमाह—तस्मादिति ॥ लकार एवानेकार्थाभिधायीति । क्रियायामनेकार्थगतारोपितसंख्याभिधायीत्यर्थः ॥ नन्वक्षा इति भज्यन्तामिति च बहुवचनं कथमत आह—शकटाक्षेति ॥ तत्रैकैकाक्षस्यैकैकक्रियायामन्वयेन सहविवक्षा कथमित्याशङ्क्य तामुपपादयति—तत्रेति । एकैकाक्षस्यैकैकक्रिया विवक्षितेत्यभिमानः ॥ वस्तुतः सहविवक्षाभावेपि लोकन्यायसिद्धं विद्धम्मानसेतिवत् तत्रं बहुवचनान्तानामत्रापीति भाष्याशयः । एकशेषशब्देन च तत्रमेव लक्ष्यत इत्याहुः ॥

(आक्षेपभाष्यम्)

एवं च कृत्वा सोपि दोषो भवति—यदुक्तम्—*तत्र युष्मदस्मदन्येषु प्रतिषेधः शेषत्वात्* इति ॥

(उद्द्योतः) भाष्ये सोपि दोष इति । विप्रतिषेधाङ्गीकाररूपो यो दोषस्तेनोक्तस्तदङ्गीकारे तदुक्तो द्वितीयो दोषोपि स्यात् इत्यर्थः ॥

(आक्षेपपरिहारस्मारणभाष्यम्)

नैष दोषः । परिहृतमेतत्—*सिद्धं तु युष्मदस्मदोः प्रतिषेधात्* इति ॥

(उद्द्योतः) परिहृतमेतदिति । शङ्कितैवेति शेषः ॥

(तटस्थाक्षेपभाष्यम्)

स तर्हि प्रतिषेधो वक्तव्यः ? ॥

(समाधानभाष्यम्)

न वक्तव्यः । शेषे प्रथमो विधीयते । नहि शेषश्चान्यश्च शेषग्रहणेन गृह्यते ॥

(प्रदीपः) नहि शेषश्चान्यश्चेति । उपयुक्तादन्यः शेषः । युष्मदस्मदोश्चोपयुक्तयोः सद्भावान्नास्ति शेषत्वम् ॥

(उद्द्योतः) उपयुक्तादन्य इति । अस्योपयुक्तासमभिव्याहृत इत्यादिः । शेषपदस्य तत्रैवार्थे शक्तेरिति भावः ॥

(आक्षेपभाष्यम्)

भवेत्—प्रथमो न स्यात् । मध्यमोत्तमावपि न प्राप्नुतः ॥ किं कारणम् ? । युष्मदस्मदोरुपपदयोर्मध्यमोत्तमावुच्येते । न च युष्मदस्मदी अन्यश्च युष्मदस्मद्ग्रहणेन गृह्यते ॥

(प्रदीपः) इतर एतत्सामर्थ्यमविद्वानाह—भवेदिति ॥

(उद्द्योतः) एतत्सामर्थ्यं, शब्दशक्तिम् । तेनावधारणमाश्रितमिति भ्रमस्तस्येति भावः ॥

(आक्षेपबाधकभाष्यम्)

यदत्र युष्मद् यच्चास्मच्च तदाश्रयौ मध्यमोत्तमौ भविष्यतः ॥

(प्रदीपः) इतर आह—यदत्रेति । तत्सन्निधौ शेषत्वाभावात्तन्निबन्धनमेव कार्यं भवतीत्यर्थः ॥

(उद्द्योतः) भाष्ये—यदत्र युष्मदिति । समुदायस्य युष्मत्त्वाभावेपि तदवयवयुष्मदमादाय मध्यम इत्यर्थः ॥

(आक्षेपभाष्यम्)

यथैव तर्हि यदत्र युष्मद्यच्चास्मच्च तदाश्रयौ मध्यमोत्तमौ भवतः, एवं योऽत्र शेषस्तदाश्रयः प्रथमो भविष्यति ॥

(प्रदीपः) इतरः शेषपदार्थमविद्वानाह—यथैवेति ॥

(समाधानभाष्यम्)

एवं तर्हि शेष उपपदे प्रथमो विधीयते । उपोच्चारि पदमुपपदम् । यच्चात्रोपोच्चारि, न स शेषः । यश्च शेषः, न तदुपोच्चारि ॥

(प्रदीपः) एतद्विचारणीयमप्युपेक्ष्योपपदार्थं वर्णयितुमाह—एवं तर्हीति ॥ यच्चात्रेति । युष्मदस्मदोः श्रवणात्तदभावे च शेषसद्भावात् ॥ यश्च शेष इति । देवदत्तश्चेति ॥ न तदिति । नहि तस्यैव साधनत्वं किं तर्हि युष्मदस्मदर्थयोरपि ।

(उद्द्योतः) एतद्विवरणीयमपीति । एतत् शेषपदशक्यं विवरीतुं योग्यमपीत्यर्थः ॥ उपेक्ष्येति । स्फुटत्वादिति भावः ॥ उपपदार्थमिति । उपपदानि तद्विशेषणान्युपपदसमानाधिकरणपदस्थानि पदानि तदर्थमित्यर्थः ॥ सूत्रावकाशं दर्शयति—तदभावे चेति ॥ नहि तस्यैवेति । न तदितिभाष्यस्य न तदेवेत्यर्थ इति भावः । अनेन—नं पारिभाषिकमुपपदम्, किं तु यौगिकमिति निर्णीतम् ॥

(आक्षेपभाष्यम्)

भवेत्—प्रथमो न स्यान्मध्यमोत्तमावपि न प्राप्नुतः ॥ किं कारणम् ? । युष्मदस्मदोरुपपदयोर्मध्यमोत्तमावुच्येते । उपोच्चारि पदमुपपदं यच्चात्रोपोच्चारि, न ते युष्मदस्मदी । ये च युष्मदस्मदी, न तदुपोच्चारि ॥

(समाधानभाष्यम्)

एवं तर्हि—शेषेण सामानाधिकरण्ये प्रथमो विधीयते । न चात्र शेषेणैव सामानाधिकरण्यम् ॥

(प्रदीपः) न चात्र शेषेणैवेति । किं तर्हि युष्मदस्मदर्थेनापि, तद्भावाच्च शेषत्वाभाव इत्यर्थः ॥

(आक्षेपभाष्यम्)

भवेत्—प्रथमो न स्यात्, मध्यमोत्तमावपि तु न प्राप्नुतः ॥ किं कारणम् ? । युष्मदस्मद्भ्यां सामानाधिकरण्ये मध्यमोत्तमावुच्येते । न चात्र युष्मदस्मद्भ्यामेव सामानाधिकरण्यम् ॥

(समाधानभाष्यम्)

एवं तर्हि "त्यदादीनि सर्वैर्नित्यम्" इत्येवमत्र युष्मदस्मदोः शेषो भविष्यति । तत्र युष्मदि मध्यमः अस्मद्युत्तम इत्येव सिद्धम् ॥

(प्रदीपः) एवं तर्हीति । यद्यप्यनेकशेषे दोष उपक्रान्तस्तथाप्येकशेषेपि दूषणार्थोयमुपक्रमः ॥

(उद्द्योतः) नन्वनेकशेषे दोषे प्रक्रान्ते कथमेकशेषेणान्यथासिद्धिरुक्तेत्यत आह—यद्यपीति । एवं चैकशेषे तयोरेवावस्थानाच्छास्त्रमत्र शेष इति न प्रथम इति भावः ॥

(समाधानबाधकभाष्यम्)

न सिध्यति । स्थानिन्यपीति प्रथमः प्राप्नोति ॥

(प्रदीपः) स्थानिन्यपीति । अप्रयुज्यमाने प्रयुज्यमाने च शेषे प्रथमविधानात् ॥

(उद्द्योतः) एकशेषेपि दोषमाह—भाष्ये न सिध्यतीति ।

स्थानिन्यपीति । तद् व्याचष्टे—अप्रयुज्यमाने इति । अनेन कैयटेन स्थानिपदार्थो निर्णीतः ॥

(आक्षेपान्तरभाष्यम्)

'त्यदादीनां खल्वपि यद्यत्परं तत्तच्छिष्यते' इति यदा भवतः शेषस्तदाश्रयः प्रथमः प्राप्नोति ॥

(प्रदीपः) दोषान्तरमप्याह—त्यदादीनामिति ॥

(आक्षेपान्तरभाष्यम्)

युष्मदि मध्यमः 'अस्मद्युत्तमः' इत्येवोच्यते ताविह न प्राप्नुतः—परमत्वं पचसि परमाहं पचामीति ॥

(प्रदीपः) एतदपरिहार्यं मन्यमानो लब्धेच्छोऽन्यदप्याह—युष्मदीति ॥ परमत्वमिति । युष्मदस्मदोर्विशिष्टरूपपरिग्रहादस्य च शब्दान्तरत्वात् ॥

(आक्षेपबाधकैकदेशिभाष्यम्)

तदन्तविधिना भविष्यति ॥

(प्रदीपः) आचार्यदेशीय आह—तदन्तविधिनेति । युष्मदस्मदोरुपपदस्य विशेषणत्वात्तदन्तविधिः ॥

(आक्षेपभाष्यम्)

इहापि तर्हि तदन्तविधिना प्राप्नुतः—अतित्वं पचति, अत्यहं पचतीति ॥

(प्रदीपः) चोदको दोषमाह—इहापीति । अतित्वमिति । त्वामतिक्रान्त इति समासः ॥

(उद्द्योतः) अतिशयितस्त्वमिति विग्रहे इष्टापत्तिरत आह—त्वामतीति ॥

(आक्षेपान्तरभाष्यम्)

ये चाप्येते समानाधिकरणवृत्तयस्तद्धितास्तत्र मध्यमोत्तमौ न प्राप्नुतः—त्वत्तरः पचसि मत्तरः पचामीति । त्वद्रूपः पचसि, मद्रूपः पचामि । त्वत्कल्पः पचसि, मत्कल्पः पचामीति ॥

(प्रदीपः) एवं तदन्तविधावतिव्याप्तिमुक्त्वाऽव्याप्तिमाह—ये चाप्येते इति ॥ त्वत्कल्प इति । ईषदसमाप्तस्त्वं त्वत्कल्प इति कालान्तरप्रसिद्धगुणरहितो युष्मदर्थ एव त्वत्कल्पशब्देनोच्यते । न तु तत्सदृशं पदार्थान्तरम् । तदभिधाने युष्मदर्थस्य साधनत्वाभावाद् मध्यमाभावात् । एवं मत्कल्प इति बोद्धव्यम् ॥

(एकदेशिसमाधानभाष्यम्)

एवं तर्हि "युष्मदस्मद्वति" इत्येवं भविष्यति ॥

(प्रदीपः) आचार्यदेशीय आह—एवं तर्हीति । सौत्रत्वान्निर्देशस्य मतुब्लोपोऽभिधास्यत इति भावः ॥

(आक्षेपभाष्यम्)

इहापि तर्हि प्राप्नुतः—अतित्वं पचति अत्यहं पचतीति ॥

(प्रदीपः) चोदक आह—इहापीति ॥

(सिद्धान्तिसमाधानभाष्यम्)

एवं तर्हि युष्मदि साधने 'अस्मदि साधने' इत्येवं भविष्यति । एवं च कृत्वा सोऽप्यदोषो भवति, यदुक्तम्—*तत्र युष्मदस्मदन्येषु प्रतिषेधः शेषत्वाद्* इति ॥

(प्रदीपः) आचार्य आह—एवं तर्हीति । समानाधिकरणे इति वचनाद्युष्मदस्मदर्थेन यत्र लान्तस्य सामानाधिकरण्यं तत्र मध्यमोत्तमाभ्यां भवितव्यमिति नास्ति कश्चिद्दोषः ॥ एवं च कृत्वेति । युष्मदस्मदर्थस्य साधनत्वाच्छेषत्वाभावः ॥

(उद्द्योतः) यत्र लान्तस्येत्यन्तपदं वृथेति केचित् ॥ शेषत्वाभाव इति । उपयुक्तासमभिव्याहृत उपयुक्तादन्यः शेषपदेनोच्यत इति भावः । एवं तर्हि युष्मदि साधने इत्यनेन समानाधिकरण इत्यस्यार्थो निर्णीतः । साधने इत्यस्य लकारवाच्यसाधने क्रियया समानाधिकरणे इत्यर्थः । एतदर्थमेवान्त्यपदमित्यन्ये ॥

(समाधानान्तरभाष्यम्)

अथ वा "प्रथमः" उत्सर्गः करिष्यते । तस्य युष्मदस्मदोरुपपदयोर्मध्यमोत्तमावपवादौ भविष्यतः । तत्र युष्मद्गन्धश्चास्मद्गन्धश्चास्तीति कृत्वा मध्यमोत्तमौ भविष्यतः ॥

(प्रदीपः) अथ वेति । प्रथम इत्येतावत्सूत्रं क्रियते । अनाश्रितविषयविशेषः प्रथमो विधीयमान उत्सर्गो भवति । तस्य विषयविशेषे विधीयमानौ मध्यमोत्तमावपवादौ भवतः । तत्रापवादनिमित्तसद्भावाद्व्यामिश्रेऽपि विषये मध्यमोत्तमावेव भविष्यतः, न तु प्रथम इत्यर्थः ॥

(उद्द्योतः) अनाश्रितेति । तिप्तसिनि सिद्धे इदं सूत्रं तदनुवादो विषयविशेषेऽपवादबोधनायेति भावः । अत एव भावे प्रथमपुरुषसिद्धिरिति बोध्यम् ॥

(आक्षेपभाष्यम्)

अथेह कथं भवितव्यम्—अत्वं त्वं संपद्यते इति त्वद्भवति मद्भवतीति । आहोस्वित्त्वद्भवसि मद्भवामीति ? ॥

(प्रदीपः) अत्वं त्वमिति । प्रकृतिविकृत्योरभेदविवक्षायां च्विप्रत्ययः तत्र किं प्रकृत्याश्रयेण प्रथमेन भाव्यमथ विकृत्याश्रयेण मध्यमेनेति प्रश्नः ॥

(समाधानभाष्यम्)

त्वद्भवति मद्भवतीत्येवं भवितव्यम् ॥

(प्रदीपः) अत्रोत्तरम्—त्वद्भवतीति । प्रकृतेरेव विकाररूपेण संपत्तौ कर्तृत्वमिति भावः ॥

(उद्द्योतः) विकाररूपेणेति । आरोपितविकाररूपेणेत्यर्थः ॥

(आक्षेपभाष्यम्)

मध्यमोत्तमौ कस्मान्न भवतः ? ॥

(प्रदीपः) मध्यमोत्तमौ कस्मादिति । यथा प्रकृतिस्तद्धर्मसमाचाराद्युष्मदस्मद्व्यपदेशं लभते तथा मध्यमोत्तमावपि प्राप्नुतः ॥

(समाधानभाष्यम्)

'गौणमुख्ययोर्मुख्ये संप्रत्ययो भवति'। तद्यथा— "गौरनुबन्ध्योऽजोऽग्नीषोमीयः" इति न वाहीकोऽनुबध्यते ॥

(प्रदीपः) गौणमुख्ययोरिति । तद्धर्मसमाचारादारोपितमत्र युष्मदर्थरूपत्वमिति भावः ॥ शिष्टं भाष्यम् "ओत्" इत्यत्र व्याख्यातम् । तत एवावधार्यताम् ॥

(आक्षेपभाष्यम्)

कथं तर्हि वाहीके वृद्ध्यात्वे भवतः—गौर्वाहीकस्तिष्ठति गामानयेति ? ॥

(समाधानभाष्यम्)

अर्थाश्रयएतदेवं भवति । यद्धि शब्दाश्रयं शब्दमात्रे तद्भवति । शब्दाश्रये च वृद्ध्यात्वे ॥ युष्मदुप० ॥ १०४ ॥ १०६ ॥ १०७ ॥

(प्रदीपः) यदुक्तं भवतः शेषइति तत्रोत्तरमाहुः— युष्मदस्मद्भवतु इत्येवं न संनिवेश आश्रणीयः । [किं तु भवतु युष्मदस्मदिति ।] ततश्चास्मद एव शेषो न तु भवतः । पूर्वशेषदर्शनाच्चेति वचनाद्वा ॥ १०४ ॥ १०६ ॥ १०७ ॥

(उद्योतः) न संनिवेश आश्रणीय इत्यस्य किं तु भवतु युष्मदस्मदितिशेषः ॥ वचनाद्वेति । अलिङ्गश्चेतनविषयो युष्मदर्थो, भवदर्थस्तु न तथेति न युष्मदर्थसमानार्थत्वमिति बोध्यम् । यदा भवतः शेषस्तदा भवत्येव प्रथम इत्याशयेन भाष्ये तत्रोत्तरानुक्तिरित्यन्ये ॥ १०४ ॥ १०६ ॥ १०७ ॥

(२१९ संहितासंज्ञासूत्रम् ॥ १।४।४ आ० २४ सू०)

३४८ परः संनिकर्षः संहिता ॥१।४।१०८

(प्रदीपः) परः सं० ॥ १०८ ॥ पूर्ववर्णोच्चारणानन्तरमेव यद्वर्णान्तरमुच्चार्यते न तु तच्छून्यान्तरालसद्भावः स पर उत्कृष्टः सन्निकर्षः प्रत्यासत्तिलक्षणः संहितासंज्ञ इति सूत्रार्थः ॥

(उद्योतः) परः सं ॥ १०८ ॥ परो वर्णान्तराव्यवहित इत्यर्थे मध्यमादिवृत्तावपि सेत्स्यतीत्यग्रिमभाष्यासंगतिरत आह— पूर्वेति । वर्णान्तरव्यवायेऽव्यवहितपरत्वाभावादेवातिप्रसङ्गविरहाद्दे- क्षोभणचीत्यादौ संहिताधिकारवैयर्थ्या[illegible]रेः स नार्थ इति भावः ॥

(मध्यमाविलम्बितयोरपि संहितासंज्ञासाधनाधिकरणम्)

(११७३ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ परः संनिकर्षः संहिता चेद्द्रुतायामसंहितम् ॥ * ॥

(भाष्यम्) परः संनिकर्षः संहिता चेदद्रुतायां वृत्तौ संहितासंज्ञा न प्राप्नोति । द्रुतायामेव हि परः सन्निकर्षो वर्णानां नाद्रुतायाम् ॥

(प्रदीपः) एवं स्थिते चोद्यते—पर इति । द्रुतायामेव वृत्तावनन्तरोक्तः परः सन्निकर्षः संभवति न तु मध्यमायां विलम्बितायां चेत्यर्थः ॥ असंहितमिति । संहितासंज्ञाया अभाव इत्यर्थाभावेऽव्ययीभावः । अविद्यमाना वा संहिता अस्मिन्निति बहुव्रीहिः ॥

(उद्योतः) ननु नञ्तत्पुरुषे उत्तरपदार्थप्रधानतया नपुंसकनिर्देशोऽयुक्तोऽत आह—अव्ययीभाव इत्यादि । पूर्वपदार्थप्राधान्येऽव्ययीभाव उत्तरपदार्थप्राधान्ये तत्पुरुष इति व्यवस्थितेरिति भावः ॥ वस्तुतः संहितशब्दोपि परसंनिकर्षवाची क्लीबः, तेनायं तत्पुरुष एव । असंहितमारोपितं संधानं परसंनिकर्षः, तेन तदभावात्संहितासंज्ञा न प्राप्नोतीत्यर्थः ॥ नञाऽव्ययीभावस्तु नास्त्येवेति नञ्सूत्रे वक्ष्यते ॥ बहुव्रीहिरिति । पौर्वापर्यं चान्यपदार्थ इत्यभिमानः ॥ अत्राद्यमेव युक्तं संहितासंज्ञा न प्राप्नोतीति भाष्यव्याख्यानाद् बहुव्रीहेस्तत्पुरुषस्येवाव्ययीभावस्यापि लघुत्वाच्च योग्यान्यपदार्थाभावाच्च॥

(११७४ सिद्धान्तवार्तिकम् ॥ २ ॥)

॥ * ॥ तुल्यः सन्निकर्षः ॥ * ॥

(भाष्यम्) तुल्यः सन्निकर्षो वर्णानां द्रुतमध्यमविलम्बितासु वृत्तिषु ॥

(प्रदीपः) द्रुतमध्यमविलम्बितास्विति । द्रुता च मध्यमा च विलम्बिता चेति द्वन्द्वे कृते भाष्यकारवचनप्रामाण्याद्ध्रस्वः । सर्वासु वृत्तिषु तुल्यः सन्निकर्षः नैरन्तर्योच्चारणात् ॥

(उद्योतः) आद्यस्योत्तरपदपरत्वाभावान्मध्यमस्य पूर्वपदत्वाभावात्सामानाधिकरण्याभावाच्च पुंवत्त्वाप्राप्तेराह—भाष्यकारेति । ङ्यापोः संज्ञाछन्दसोर्बहुलमित्यनेनेति भावः ॥

(आक्षेपभाष्यम्)

किंकृतस्तर्हि विशेषः ? ॥

(प्रदीपः) विशेष इति । वृत्तीनामिति शेषः । क्वचिद्वृत्तिविशेष इत्येव पाठः ॥

(११७५ समाधानवार्तिकम् ॥ ३ ॥)

॥ * ॥ वर्णकालभूयस्त्वं तु ॥ * ॥

(भाष्यम्) वर्णानां तु कालभूयस्त्वम् । तद्यथा— हस्तिमशकयोस्तुल्यः सन्निकर्षः प्राणिभूयस्त्वं तु ॥

(प्रदीपः) वर्णानां त्विति । वर्णोपलब्धिकालभेदाद्वर्णकालभूयस्त्वमुच्यते । द्रुतायां स्वल्प उपलब्धिकालः । मध्यमायामधिकः । विलम्बितायामधिकतरः । प्राकृतवैकृतभेदाद्भिन्ना ध्वनयः । तत्र वैकृतध्वनिवशात्तस्यैव वर्णस्य पुनः पुनरुपलब्धिर्भवतीति ध्वनिभेदाद्वृत्तिभेदः ॥ किंकृत इति कारणे

पृष्टे **वर्णकालभूयस्त्वं त्विति** सामर्थ्यात्कारणमेवोक्तं भवतीति ॥ **हस्तिमशकयोरिति** । हस्तिनो हस्तिना यः सन्निकर्षः, मशकस्य मशकेन, स तुल्यः परस्परापेक्षयेत्यर्थः ॥ **प्राणिभूयस्त्वमिति** । हस्तिनौ महान्तं देशं व्याप्नुतो मशकौ तु स्वल्पम् । नैरन्तर्यं त्वविशिष्टमित्यर्थः ॥

(उद्योतः) ननु सर्ववृत्तिषु वर्णानामिकरूपत्वात्कथं वर्णकालभूयस्त्वमत आह—**वर्णोपलब्धीति** । वैकृत आलस्यादिजन्यो ध्वनिः॥ पुनःपुनरुप[लब्धिश्चाविच्छेदेनोप]लब्धिधारा न तु विच्छिद्य विच्छिद्य ग्रहणमिति । एतच्च **तपरसूत्रे** विस्तरेण निरूपितम् ॥ **ध्वनिभेदादिति** । वैकृतध्वनिभेदादित्यर्थः॥ननु **किंकृत** इति कारणप्रश्ने फलकथनेनोत्तरमसंगतमत आह—**कारणमेवेति** । **वर्णकालभूयस्त्वं त्विति** भाष्यस्य कारणं **वृत्तिविशेषस्येति** शेषः । तच्च वैकृतध्वनिरूपं स्वयमुक्तमिति भावः ॥ हस्तिमशकयोः परस्परसंनिकर्ष इति नार्थ इत्याह—**हस्तिन इति** । अत एव **प्राणिभूयस्त्वमित्यि**मग्रन्थसंगतिरिति भावः । प्राणिशब्देनात्र शरीरम् ॥

(आक्षेपशेषभाष्यम्)

यद्येवम्,

(प्रदीपः) वर्णानां व्यञ्जकध्वनिकृतं यथोक्तं भेदमप्रतिपद्यमानः स्वगतमेव भेदं मत्वा चोदयति—**यद्येवमिति** ॥ शिष्टं भाष्यं **तपरस्तत्कालस्येत्यत्र** व्याख्यातं तत एवावधार्यताम् ॥

(उद्योतः) **व्यञ्जकध्वनीति** । उपलब्धिधाराजनकध्वनीत्यर्थः ॥

(द्रुतमध्यमविलम्बितासु तपरफलाधिकरणम्)

(११७६ आक्षेपवार्तिकम् ॥ ४ ॥)

॥ * ॥ द्रुतायां तपरकरणे मध्यमविलम्बितयोरुपसंख्यानं कालभेदात् ॥ * ॥

(भाष्यम्) **द्रुतायां तपरकरणे मध्यमविलम्बितयोरुपसंख्यानं कर्तव्यम् ॥ किं कारणम् ? । कालभेदात् । ये द्रुतायां वृत्तौ वर्णास्त्रिभागाधिकास्ते मध्यमायाम् । ये मध्यमायां वृत्तौ वर्णास्त्रिभागाधिकास्ते विलम्बितायाम् ॥**

(११७७ समाधानवार्तिकम् ॥ ५ ॥)

॥ * ॥ उक्तं वा ॥ * ॥

(भाष्यम्) **किमुक्तम् ? । *सिद्धं त्ववस्थिता वर्णा वक्तुश्चिराचिरवचनाद् वृत्तयो विशिष्यन्ते* इति ॥**

(उद्योतः) भाष्ये—**उक्तं चेति** । वचनारम्भापेक्षो विकल्पः ॥

(न्यासान्तरभाष्यम्)

अथवा "शब्दाविरामः संहिता" इत्येतल्लक्षणं करिष्यते ॥

(प्रदीपः) **शब्दाविराम इति** । यदा प्रयोक्ता शब्दोच्चारणान्न विरमति तदा शब्दाविरामः । स च मध्यमविलम्बितयोरपि परसन्निकर्षाभावेप्यस्तीति सिद्धा संहितासंज्ञा ॥

(उद्योतः) ननु शब्दानां नित्यत्वाद्विरामाभावेऽविराम इति विशेषणं व्यर्थमत आह—**यदेति** । शब्दशब्देन तदुच्चारणं लक्ष्यत इति भावः ॥

(११७८ आक्षेपवार्तिकम् ॥ ६ ॥)

॥ * ॥ शब्दाविरामे प्रतिवर्णमवसानम् ॥ * ॥

(भाष्यम्) **शब्दाविरामे प्रतिवर्णमवसानसंज्ञा प्राप्नोति ॥ किमिदं प्रतिवर्णमिति ? । वर्णे वर्णे प्रति प्रतिवर्णम् । येनैव प्रयत्नेनैको वर्ण उच्चार्यते विच्छिन्ने वर्णे उपसंहृत्य तमन्यमुपादाय द्वितीयः प्रयुज्यते तथा तृतीयस्तथा चतुर्थः ॥**

(प्रदीपः) **शब्दाविरामे प्रतिवर्णमिति** । भिन्नप्रयत्नजनितध्वनिव्यङ्ग्यत्वाद्वर्णानां प्रतिवर्णं प्रयत्नभेदादेकप्रयत्नाविच्छेदाभावात् प्रथमप्रयत्नोच्चारितवर्णानन्तरं प्रयत्नान्तरेण वर्णान्तरोच्चारणादेकैकस्य वर्णस्य विरामसद्भावादवसानसंज्ञा प्राप्नोति ॥

(उद्योतः) नन्वविरामेऽवसानसंज्ञाप्राप्तिरित्यसंगतमत आह—**भिन्नेति** । ध्वनिपदेनात्र कण्ठताल्वाद्यभिघातः । प्रयत्नभेदे एकप्रयत्नाविच्छेदाभावो हेतुः । **अविच्छेदाभाव** इत्यस्यारोपितविच्छेदप्रतियोगिकोऽभाव इत्यर्थः । तेनाभावप्रतियोगिकोऽभावः कथं, तस्य भावप्रतियोगिकत्वनियमादिति न शङ्क्यम् । विच्छेदश्च निवृत्तिविरामापरपर्यायः क्रियाविशेष इति बोध्यम् ॥ **एकैकस्य वर्णस्येति** । एकवर्णोच्चारणानन्तरं तन्नाशकाले द्वितीयवर्णोच्चारणफलकद्वितीययत्नोत्पत्त्यधिकरणकाले च वर्णाभावात्तद्विरामोऽस्त्येवेत्यर्थः । यद्यप्यवच्छेदकभेदेनानेकयत्नोत्पत्तिरपि युगपत्, तथापि प्रकृते नाभिरूपैकदेशावच्छेदेनानेकयत्नोत्पत्तिर्युगपद्विरुद्धा ॥ वस्तुतो यत्नायौगपद्यमेव । नर्तक्या नानावयवावच्छिन्नक्रियाः क्षणभेदेनैव । कालसौक्ष्म्यात्तु तदग्रह इत्याशयः ॥ **अवसानसंज्ञा प्राप्नोतीति** । एवं चैकसंज्ञाधिकारात्संहितासंज्ञा न स्यादिति भावः ॥ **विच्छिन्नेवर्णे** तेनैव यत्नेन नष्ट इत्यर्थो बोध्यः ॥ एतेन **येनैवेत्यत्रै**वकारो व्यर्थ इत्यपास्तम् ॥ **उपसंहृत्य** पूर्वयत्नं त्यक्त्वेत्यर्थः ॥ **अन्यमिति** । यत्नान्तरमित्यर्थः ॥

(समाधानभाष्यम्)

एवं तर्ह्यनवकाशा संहितासंज्ञाऽवसानसंज्ञां बाधिष्यते ॥

(प्रदीपः) **अवसानसंज्ञामिति** । वर्णान्तरानुच्चारणे वृक्ष इत्यादौ सावकाशामिति भावः । तेन सर्वथा वर्णानां यो विरामः सोऽवसानसंज्ञो न तु नान्तरीयक इत्यर्थः ॥

(समाधानान्तरभाष्यम्)

अथ वा अवसानसंज्ञायां प्रकर्षगतिर्विज्ञास्यते—

साधीयो यो विराम इति ॥ कश्च साधीयः? । यः शब्दार्थयोर्विरामः ॥

(प्रदीपः) अथ वेति । सर्वत्र विरामसद्भावात्पुनः-श्रुत्या विशेष आश्रीयते ॥ शब्दार्थयोरिति । अन्यत्र तु सत्यपि शब्दविरामे पदार्थस्य वाक्यार्थस्य वाऽविरामान्न भवत्यवसानसंज्ञा ॥

(उद्योतः) प्रकर्षबोधकशब्दाभावात्कथं तत्प्रतीतिरत आह—सर्वत्रेति । शब्दस्य विरामः श्रवणकृतः । अर्थस्य बोधकृतः ॥ अन्यत्र त्विति । वर्णानन्तरं वर्णान्तरोच्चारणे मध्यकाले इत्यर्थः ॥

(न्यासान्तरभाष्यम्)

अथ वा "ह्रादाविरामः संहिता" इत्येतल्लक्षणं करिष्यते ॥

(प्रदीपः) ह्रादाविराम इति । प्रयत्नविशेषजनितो वर्णविरामेऽप्यनुरणनरूपो वर्णान्तरोच्चारणेप्यनुवर्तमानो घोषो ह्राद उच्यते ॥

(उद्योतः) घोषः । ध्वनिविशेषः ॥

(११७९ आक्षेपवार्तिकम् ॥ ७ ॥)

॥ * ॥ ह्रादाविरामे स्पर्शाघोषसंयोगेऽसन्निधानादसंहितम् ॥ * ॥

(भाष्यम्) ह्रादाविरामे स्पर्शानामघोषाणां च संयोगेऽसंनिधानात्संहितासंज्ञा न प्राप्नोति—कुक्कुटः पिप्पकः पित्तमिति ।

(प्रदीपः) स्पर्शाघोषसंयोग इति । वर्ग्याणां प्रथमद्वितीयानां शषसानां च संयोगे घोषविच्छेदादसन्निधानात्संहितासंज्ञाया अप्राप्तिरित्यर्थः ॥ अघोषसंयोग इत्येव सिद्धत्वात् स्पर्शग्रहणमनर्थकम् अस्पर्शानामप्यघोषाणां शससानां संयोगे तुल्यन्यायत्वात् संज्ञाया अप्रसङ्गात् । न च स्पर्शानाम् अघोषाणां चेति समुच्चयः । घोषवतां स्पर्शानां संयोगे दोषाप्रसङ्गात् ॥ कुक्कुट इति । कुक्कुट इवायमिति कनो लुम्मनुष्ये इति लुपि कृते संज्ञायामुपमानमित्याद्युदात्तत्वं शिष्टमनुदात्तं ततः संहितायां विधीयमानमुदात्तादनुदात्तस्य स्वरितत्वं न स्यात् ॥

(उद्योतः) घोषविच्छेदादिति । असत्त्वादेव विच्छेदस्तदाह—असंनिधानादिति ॥ घोषवतामिति । तृतीयचतुर्थानामित्यर्थः ॥ दोषाप्रसङ्गादिति । तथा व्याख्याने हि तत्रापि दोष इति भाष्याल्लभ्यते तच्चासंगतं स्यात्तत्र दोषाप्राप्तेरिति भावः । स्पर्शानां मध्येऽघोषस्येत्यर्थः ॥ शषससंयोगे फलं नास्तीति भाष्याशयमन्ये ॥ ननु कुक्कुटादौ न किंचित्संहिताकार्यमत आह—कस्य इति ॥

(प्रत्याक्षेपभाष्यम्)

किमुच्यते संयोग इति । अथ यत्रैकः पचतीन्ति॥

(प्रदीपः) पचतीति । अत्रापि चकारस्याघोषत्वादकारोच्चारणे घोषविच्छेदात् स्वरितत्वाप्रसङ्गः ॥

(उद्योतः) घोषविच्छेदादिति । असत्त्वादेव विच्छेदः ॥ भाष्ये—पचतीत्यस्य तत्र कथमिति शेषः ॥

(प्रत्याक्षेपपरिहारभाष्यम्)

एकः पूर्वपरयोर्ह्रादेन प्रच्छाद्यते । तद्यथा । द्वयो रक्तयोर्वस्त्रयोर्मध्ये शुक्लं वस्त्रं तद्गुणमुपलभ्यते । बदरपिटके रिक्तको लोहकंसस्तद्गुण उपलभ्यते ॥

(प्रदीपः) ह्रादेनेति । द्वयोरकारयोर्घोषवतोर्मध्ये चकारो घोषवानिव लक्ष्यत इत्यर्थः । आश्रयान्तरगतोपि गुण आश्रयान्तर उपलभ्यत इति दृष्टान्तेन दर्शयति—द्वयोरिति ॥

(उद्योतः) कुक्कुट इत्यादौ कृतशङ्कः पचतीत्यत्र परिहरति—एकः पूर्वेति ॥

(समाधानभाष्यम्)

एकेन तुल्यः सन्निधिः ॥ यथैवैको वर्णो ह्रादेन प्रच्छाद्यते एवमनेकोपि ।

(प्रदीपः) एकेनेति । अनेकस्य यः सन्निकर्षः स एकेन तुल्यः । यथैकोऽतद्गुणोपि तद्गुणवस्त्वन्तरसन्निधौ तद्गुण उपलभ्यते तथाऽनेकोपि स्फटिकादिरर्थ इत्यर्थः ॥

(उद्योतः) तन्न्यायेन कुक्कुटादावपि समाधत्ते—एकेनेत्यादिना ॥

(न्यासान्तरभाष्यम्)

अथवा "पौर्वापर्यमकालव्यवेतं संहिता" इत्येतल्लक्षणं करिष्यते ॥

(प्रदीपः) अथ वेति । वर्णान्तरोच्चारणकालादन्येन वर्णशून्येन कालेनाव्यवहितं पौर्वापर्यं संहितेति लक्षणं क्रियते । तेन मध्यमविलम्बितयोः परमसन्निकर्षाभावेपि संहितासंज्ञा सिद्ध्यति ॥

(उद्योतः) वर्णान्तरेति । वर्णान्तरोच्चारणे नान्तरीयकार्धमात्राकालादन्येनाधिकेनेत्यर्थः ॥

(११८० आक्षेपवार्तिकम् ॥ ८ ॥)

॥ * ॥ पौर्वापर्यमकालव्यवेतं संहिता चेत्पूर्वापराभावादसंहितम् [एकवर्णवर्तित्वाद्वाचः, उच्चरितप्रध्वंसित्वाच्च वर्णानाम्] ॥ * ॥

(भाष्यम्) पौर्वापर्यमकालव्यवेतं संहिता चेत्पूर्वापराभावात्संहितासंज्ञा न प्राप्नोति । नहि वर्णानां पौर्वापर्यमस्ति । किं कारणम्? । एकवर्णवर्तित्वाद्वाचः, उच्चरितप्रध्वंसित्वाच्च वर्णानाम् । एकैकवर्णवर्तिनी वाक् न द्वौ युगपदुच्चारयति ।

गौरिति गकारे यावद्वाग्वर्तते, नौकारे, न विसर्जनीये। यावद् औकारे, न गकारे, न विसर्जनीये। यावद्विसर्जनीये, न गकारे, नौकारे॥ उच्चरितप्रध्वंसित्वात्—। उच्चरितप्रध्वंसिनः खल्वपि वर्णाः। उच्चरितः प्रध्वस्तः। अथापरः प्रयुज्यते न वर्णो वर्णस्य सहायः॥

(प्रदीपः) **पूर्वापराभावादिति**। युगपत्स्थितानां देशकृतं पौर्वापर्यं दृष्टम्। वर्णास्त्वेकैकश उपलभ्यमाना यौगपद्येनासन्निधानात्कथं पौर्वापर्यमश्नुवीरन्॥ **एकवर्णवर्तित्वादिति**। सामान्येनोपक्रमात् स्त्रीप्रत्ययाभावः॥ **उच्चरितेति**। क्रमोत्पन्ना अपि वर्णा यद्यवतिष्ठेरंस्तदा स्यात् पूर्वापरव्यपदेशो ज्येष्ठमध्यमकनिष्ठव्यपदेशवत्। अनवस्थानात्तु नास्ति तात्त्विकः पूर्वापरभाव इत्यर्थः। व्यञ्जकध्वन्यपेक्षया चैतदुक्तम्। ध्वनिस्फोटभेदस्त्वन्यत्र निर्णीतत्वान्नेहोपन्यस्यते॥ **न द्वौ युगपदिति**। युगपद् द्वयोरुच्चारणे स्यादेवाव्यवधानम्। कालेन पौर्वापर्यं तु मा भूदित्यर्थः॥ **वागिति**। वागिन्द्रियमित्यर्थः। एतेन युगपदनवस्थानात् सन्निकर्षोऽप्याक्षिप्त इति विज्ञेयम्॥

(उद्द्योतः) ननु पूर्वः पूर्वकालः परश्च परकाल इति कथं पूर्वापरभावोऽत आह—**युगपदिति**। अयं भावः—यदि कालिकं पौर्वापर्यं तदेकोयणचीत्यादिसंहिताकार्यासंभवः पूर्वपरयोर्युगपत्स्थित्यभावादत एव न दैशिकमपीति॥ **अनेकश इति**। भिन्नकाले इत्यर्थः। एकैकश इति पाठान्तरम्। तत्रापूपौ द्वाविितिवत् व्यतिलुनत इतिवच्च द्विर्वचनशसोर्यौगपद्यं बोध्यम्। तद्धितमात्रेण तु न वीप्साप्रतीतिरल्पश इत्यर्थस्यापि प्रतीतेः॥ नन्वेकैकवर्णवर्तिनीत्वादित्युचितमगुणवचनत्वेन पुंवत्त्वाप्राप्तेरत आह—**सामान्येनेति**। तेनोपक्रमे च नपुंसकत्वमेवेति भावः॥ अनेन युगपदुपलम्भं निरस्य युगपद्वास्तवीं सत्तामपि निरसितुमाह—भाष्ये **उच्चरितेति**॥ **उच्चरितप्रध्वंसित्वम्**। उच्चारणाधिकरणकालोत्तरकालवृत्तिध्वंसप्रतियोगित्वरूपम्। उच्चारणाधिकरणकालोऽपि क्षणसमूहरूपः प्रत्यक्षयोग्यः। क्षणिकस्य प्रत्यक्षायोगात्॥ **यद्यवतिष्ठेरन्निति**। कालिकपौर्वापर्यमपि युगपदवस्थितेष्वेव प्रहीतुं शक्यं न तु नष्टविद्यमानयोस्तदाह—**ज्येष्ठेत्यादि**। अयं ज्येष्ठोऽयं कनिष्ठ इति व्यवहारवदयं पूर्वोऽयं पर इति व्यवहारस्य नष्टविद्यमानयोरसंभवः। नष्टविद्यमानयोः संबन्धस्य निरूपयितुमशक्यत्वादिति भावः॥ वर्णानां स्फोटरूपाणां नित्यत्वादिदमयुक्तमत आह—**व्यञ्जकेति**। स्फोटस्य तु सर्वसाधारण्येनैकत्वात्तमादाय पौर्वापर्यस्योक्तिसंभवोऽपि नास्तीति भावः॥ **अन्यत्र**। तपरसूत्रे॥ **स्यादेवेति**। कालकृतमव्यवधानं स्यादेवेत्यर्थः। एवं च युगपदुच्चारणाभावान्न संनिकर्षो नापि पौर्वापर्यमिति भावस्तदाह—भाष्ये **अथापर इति**। तद्वर्णध्वंसानन्तरमपरो वर्णः प्रयुज्यते तावतापि स पौर्वापर्यादिव्यवहारे न वर्णान्तरस्य सहाय इत्यर्थः॥

(समाधानभाष्यम्)

एवं तर्हि—

"बुद्धौ कृत्वा सर्वाश्चेष्टाः कर्ता धीरस्तत्वन्नीतिः। शब्देनार्थान्वाच्यान्दृष्ट्वा बुद्धौ कुर्यात्पौर्वापर्यम्॥" बुद्धिविषयमेव शब्दानां पौर्वापर्यम्। इह य एष मनुष्यः प्रेक्षापूर्वकारी भवति स पश्यति अस्मिन्नर्थेऽयं शब्दः प्रयोक्तव्यः, अस्मिंस्तावच्छब्देऽयं तावद्वर्णः ततोऽयं ततोऽयमिति॥ परः संनिकर्षः॥१०८॥

(प्रदीपः) **एवं तर्हीति**। बुद्धिप्रकल्पितः सर्वः पौर्वापर्यसन्निकर्षादिव्यवहार इत्यर्थः॥ **धीरः** पण्डितः॥ **तत्वन्नीतिरिति**। तननं तत् साऽस्ति यस्याः सा तत्वती सकलविषयव्यापिनी नीतिर्बुद्धिर्यस्य स तत्त्वन्नीतिरिति। अन्ये तु **तन्वन्नीतिरिति** पठन्ति। तन्वती विषयान् व्याप्नुवती बुद्धिर्यस्येति स एवार्थः॥ १०८॥

(उद्द्योतः) **बुद्धौ कृत्वेति**। बुद्धावन्तःकरणे **चेष्टाः** कण्ठताल्वाद्यभिघातव्यापारजन्यान् शब्दान् कृत्वा प्रतिबिम्बितान् कृत्वा **शब्देन** वाच्यानर्थान् **बुद्धौ** बुद्धिरूपे देशे **दृष्ट्वा** तत्रैव पौर्वापर्यव्यवहारं कुर्यादित्यर्थः॥ **बुद्धिविषयमित्यस्य** बुद्धिस्थशब्दविषयमित्यर्थः। तत्र वक्तृबुद्धिस्थत्वमुपपादयति—**य इति**। तदर्थमेव शास्त्रप्रवृत्तेस्तस्यैव शास्त्रफलधर्मोक्तेः॥ **अस्मिन्नर्थे इति**। एतदर्थमेव बुद्धावर्थदर्शनमप्युक्तं श्लोके पौर्वापर्यमित्युपलक्षणम्॥ **अयमिति**। बुद्ध्युपारूढस्वमात्रश्रव्यसूक्ष्मोच्चारणव्यङ्ग्यशब्दपरामर्शः। अन्यथेदमः प्रत्यक्षपरामर्शकत्वादेतदनुपपत्तिः॥ **प्रयोक्तव्यः**। परप्रत्यययोग्यस्थूलोच्चारणरूपेण प्रयोगेणाभिव्यक्तव्यः॥ **अस्मिन् शब्दे** इत्यस्य व्यञ्जनीये इति शेषस्तदाह—**बुद्धिप्रकल्पित इति**। बुद्धिस्थप्रकल्पितशब्दविषय इत्यर्थः॥ **प्रकल्पितेत्यस्य** प्रतिबिम्बेन तत्तद्रूपतया प्रकल्पितेत्यर्थः॥ १०८॥

(२२० अवसानसंज्ञासूत्रम्॥ १।४।४ आ. २५ सू०)

३४९ विरामोऽवसानम्॥ १।४।१०९

(पाठनिर्णयाधिकरणम्)

(भाष्यम्) **इदं विचार्यते—अभावो वावसानलक्षणं स्याद्, विरामो वेति॥**

(प्रदीपः) **विरामः**॥ १०९॥ **इदं विचार्यत इति**। विचरति नाना गच्छति यद्वस्तु तद्विचार्यते परीक्ष्यत इत्यर्थः॥ **अभावो वेति**। केचिद्—**अभावोऽवसानमिति** पठन्ति, अन्ये तु **विरामोऽवसानमिति**। तत्र युक्तायुक्तविचारः क्रियते॥

(उद्द्योतः) **विरामो**॥ १०९॥ नाना प्रकार **गच्छति** प्राप्नोति यत्तन्नानाप्रकारं गम्यते तथा प्रापय्य किं युक्तमिति परीक्ष्यत इत्यर्थः॥ अत्र लक्षणे संदेहाभावादाह—**केचिदिति**॥

(विशेषप्रश्नभाष्यम्)

कश्चात्र विशेषः?॥

(११८१ प्रथमपक्षे दूषणवार्तिकम् ॥ १ ॥)

॥ * ॥ अभावेऽवसानलक्षणे उपर्यभाववचनम् ॥ * ॥

(भाष्यम्) अभावेऽवसानलक्षणे उपर्यभावग्रहणं कर्तव्यम् । उपरि यः अभाव इति वक्तव्यम् । पुरस्तादपि हि शब्दस्याभावस्तत्र मा भूदिति ॥ किं च स्यात् ? । रसः, रथः "खरवसानयोर्विसर्जनीयः" इति विसर्जनीयः प्रसज्येत ॥

(प्रदीपः) उपरीति । वर्णोच्चारणादूर्ध्वं योऽभावः तदुपलक्षितो वर्णोऽवसानमिति वक्तव्यं प्रागभावस्योपलक्षणत्वनिवृत्त्यर्थम् ॥ रस इति । परवत् पूर्वस्यापि रेफस्याभावविषयत्वाद्विसर्जनीयप्रसङ्गः ॥

(उद्योतः) प्रागभावस्येति । प्राग्वर्तिनः शब्दाभावस्येत्यर्थः ॥ भाष्ये—रसः रथ इत्यत्र ॥ खरवसानयोरिति विसर्जनीयः प्रसज्येतेति । पदावयवस्यावसाने रेफस्य विसर्ग इति सूत्रार्थ इति भावः ॥ खरीति वाक्ये तु रेफान्तस्य पदस्येत्यर्थ इति बोध्यम् ॥

(द्वितीयपक्षाभ्युपगमभाष्यम्)

अस्तु तर्हि—विरामः ॥

(११८२ द्वितीयपक्षे दूषणवार्तिकम् ॥ २ ॥)

॥ * ॥ विरामे विरामवचनम् ॥ * ॥

(भाष्यम्) यस्य विरामः, विरामग्रहणं तेन कर्तव्यम् ॥

(प्रदीपः) विरामे विरामवचनमिति । अधिकं कर्तव्यमित्यर्थः ॥

(विरामवादिभाष्यम्)

ननु च यस्याप्यभावः, तस्याप्यभावग्रहणं कर्तव्यम् ॥

(अभाववादिभाष्यम्)

परार्थं मम भविष्यति—'अभावो लोपः' ततः 'अवसानं च' इति ॥

(प्रदीपः) ततोऽवसानं चेति । अदर्शनमभाव इत्येक एवार्थः । तेन पुनरभावग्रहणं न कर्तव्यमित्यर्थः । तत्र लोपसंज्ञायामभावः संज्ञित्वेनाश्रीयते, अवसानसंज्ञायां तूपलक्षणत्वेन । तेन वर्णान्तराभावोपलक्षितो वर्णोऽवसानसंज्ञ इत्यर्थः । उत्तरत्र त्वभावस्यैव लोपावसानसंज्ञे व्याख्यास्येते । अस्मिन् पक्षे खरवसानयोरिति षष्ठी । खरः समीपस्य रेफस्यावसानस्य च रेफस्येत्यर्थः । अथवैकापि सप्तमी विषयभेदाद्भिद्यते—खरि परतो रेफस्य विसर्जनीयोऽवसाने च रेफे स्थानिनि विसर्जनीय इत्यादेशस्य विषयत्वेन स्थानी विवक्ष्यते ॥

(उद्योतः) अदर्शनमिति । यद्यपि तद्दर्शनाभावः, अभावश्च वर्णस्य तथाप्यभावपदेन तस्यापि लाभः । वर्णदर्शनाभाववर्णाभावयोः समनियतत्वादिति भावः ॥ अस्मिन् पक्षे इति । वर्णान्तराभावोपलक्षितवर्णस्यावसानत्वपक्षे इत्यर्थः ॥

(विरामवादिभाष्यम्)

ममापि तर्हि विरामग्रहणं परार्थं भविष्यति "विरामो लोपः" 'अवसानं च' इति ॥

(प्रदीपः) ममापीति । अभावो विराम इति पर्यायत्वं मन्यते ॥

(११८३ आक्षेपवार्तिकम् ॥ ३ ॥)

[॥ * ॥ उपरिविरामवचनम् ॥ * ॥]

(भाष्यम्) उपरि यो विराम इति वक्तव्यम् । पुरस्तादपि हि शब्दस्य विरामः, तत्र मा भूत् ॥ किं च स्यात् ? । रसः रथः "खरवसानयोर्विसर्जनीयः" इति विसर्जनीयः प्रसज्येत ॥

(आक्षेपपरिहारभाष्यम्)

नैष दोषः । आरम्भपूर्वको मम विरामः ॥

(प्रदीपः) आरम्भपूर्वक इति । निवृत्तिर्विरामः, स च प्रवृत्तस्य भवतीति भावः ॥

(उद्योतः) स च प्रवृत्तस्येति । एवं च पुरस्तान्न विरामव्यवहार इति भावः ॥

(पक्षान्तरव्याख्याभाष्यम्)

अथ वा नेदमवसानलक्षणं विचार्यते । किं तर्हि? । संज्ञी । अभावोऽवसानसंज्ञी स्याद्विरामो वेति ॥

(प्रदीपः) अवसानलक्षणमिति । अभावोपलक्षितो वर्णोऽवसानं विरामोपलक्षितो वेति पूर्वं विचारितम् । इदानीं तु तावेव संज्ञित्वेन विचार्येते । अभावो लोप इत्येकस्य संज्ञाद्वयविधानसामर्थ्याद्विषयविभाग आश्रीयते । प्रसक्ताभावो लोपसंज्ञः, अभावमात्रमवसानसंज्ञमिति ॥

(उद्योतः) भाष्ये—नेदमवसानलक्षणमिति । अवसानव्यवहारविषयस्य वर्णस्योपलक्षणभूतं वस्तु न विचार्यते इत्यर्थः ॥ प्रसक्ताभाव इति । प्रसक्तोच्चारणाभाव इत्यर्थः ॥

(विशेषप्रश्नभाष्यम्)

कश्चात्र विशेषः ? ।

(११८४ प्रथमपक्षदूषणवार्तिकम् ॥ १ ॥)

॥ * ॥ अभावेऽवसानसंज्ञिन्युपर्यभाववचनम् ॥ * ॥

(भाष्यम्) अभावेऽवसानसंज्ञिन्युपर्यभावग्रहणं कर्तव्यम्। उपरि योऽभाव इति वक्तव्यम्। पुरस्तादपि हि शब्दस्याभावस्तत्र मा भूदिति। किं च स्यात्?। रसः रथः "खरवसानयोर्विसर्जनीय" इति विसर्जनीयः प्रसज्येत ॥

(द्वितीयपक्षाभ्युपगमभाष्यम्)

अस्तु तर्हि—विरामोवसानम् ॥

(११८५ द्वितीयपक्षदूषणवार्तिकम् ॥ २ ॥)

॥ * ॥ विरामे विरामवचनम् ॥ * ॥

(भाष्यम्) यस्य विरामस्तेन विरामग्रहणं कर्तव्यम् ॥

(विरामवादिभाष्यम्)

ननु च यस्याप्यभावस्तेनाप्यभावग्रहणं कर्तव्यम्।

(अभाववादिभाष्यम्)

परार्थं मम भविष्यति—अभावो लोपस्ततोवसानं चेति ॥

(विरामवादिभाष्यम्)

ममापि तर्हि विरामग्रहणं परार्थं भविष्यति—विरामो लोपोवसानं चेति ॥

(आक्षेपभाष्यम्)

उपरि यो विराम इति वक्तव्यम् ॥

(परिहारस्मारणभाष्यम्)

ननु चोक्तम्—'आरम्भपूर्वके—' इति।

(परिहारबाधकभाष्यम्)

नावश्यमयं रमिः प्रवृत्ताविव वर्तते। किं तर्हि?। अप्रवृत्तावपि। तद्यथा—'उपरतान्यस्मिन्कुले व्रतानि' 'उपरतः स्वाध्याय' इति। न च तत्र स्वाध्यायो भूतपूर्वो भवति, नापि व्रतानि ॥

(प्रदीपः) नावश्यमिति। प्रवृत्तौ सत्यां या निवृत्तिस्तस्यामित्यर्थः ॥ उपरतान्यस्मिन्निति। न प्रवृत्य निवृत्तानि। किं तर्हि?। पूर्वमेवाप्रवृत्तानीत्यर्थः। नियतविषयत्वाच्च शब्दप्रयोगस्य शशविषाणमुपरतमिति प्रयोगाभावः ॥ क्वचिद्व्रनानीति पाठः ॥

(उद्द्योतः) प्रवृत्तौ रमेः प्रयोगस्य क्वाप्यभावादाह—प्रवृत्तौ सत्यामिति। न प्रवृत्य निवृत्तानीति पाठः। उपरतविरतौ च पर्यायौ। क्वचिद्व्रनानीति पाठ इति। व्रतानीत्यस्य स्थाने तथा पाठ इत्यर्थः। तत्र वनपदं वानप्रस्थाश्रमोपलक्षणम्। एतदन्तेन लक्षणयोः साम्यमुपपादितम् ॥

(११८६ आक्षेपवार्तिकम् ॥ ४ ॥)

॥ * ॥ भावाविरामभावित्वाच्छन्दस्यावसानलक्षणं न ॥ * ॥

(भाष्यम्) भावाविरामभावित्वाच्छब्दस्यावसानलक्षणं नोपपद्यते। किमिदं भावाविरामभावित्वादिति?। भावस्याविरामः भावाविरामः, भावाविरामेण भवतीति भावाविरामभावी, भावाविरामभाविनो भावो भावाविरामभावित्वम् ॥

(प्रदीपः) भावाविरामभावित्वादिति। इह शब्दस्य स्वसंबन्धी अभावोऽवसानलक्षणं स्यात्, शब्दान्तरस्य संबन्धी वा। न तावत् स्वसंबन्धी, विरोधात्। नहि यस्य सत्ता तस्य तदानीमेवासत्ता युज्यते। नापि शब्दान्तरसंबन्धी। नहि घटाभावः पटस्याभावो भवति। भावस्य सत्ताया अविच्छेदेन भवत्यवश्यमिति भावाविरामभावी शब्दः। नहि शब्दस्य भवनकाले सत्ता विच्छिद्यते इत्यर्थः ॥

(उद्द्योतः) अथोभयत्रापि दोषं शङ्कते—भावाविरामेति ॥ नापि शब्दान्तरेति। वावसाने इत्यादाववसाने स्थितसत्त्वेत्यर्थः प्रत्यासत्त्योन्वित इति भावः ॥ अविच्छेदेनेति। अविच्छेदाविरामौ पर्यायौ तत्प्रतियोगिनौ विच्छेदविरामौ च क्रियाविशेषरूपौ भावपदार्थौ। एतेनाभावस्य भावप्रतियोगिकत्वादिदं चिन्त्यमिति परास्तम्। अन्याभावपरो वर्ण इत्यादि त्वग्रे वक्ष्यत्येव ॥

(व्याख्यान्तरभाष्यम्)

अपर आह—भावभावित्वादविरामभावित्वाच्च शब्दस्यावसानलक्षणं नोपपद्यते—इति ॥

(प्रदीपः) अपर आहेति। भावाविरामशब्दयोर्द्वन्द्व इत्यर्थः ॥ इदानीं लक्षणद्वयस्याप्यनुपपत्तिः प्रतिपाद्यते। भावेन सत्तयाऽविरामेण अविच्छेदेन भवतीत्यर्थः। उपाधिरहितस्याभावस्य प्रतीतिर्नास्ति ॥

(उद्द्योतः) इदानीम्। अपर आहेति व्याख्यानकाले ॥ अन्ये तु वर्णानामभाव इत्युक्ते वर्णत्वावच्छिन्नप्रतियोगिताकाभाव इत्यर्थः। स च न वर्णसत्त्वे इति भाष्यार्थं इत्याहुः ॥ ननु शब्दस्य भावाविरामभावित्वेप्यभावोऽवसानमिति लक्षणे को दोषस्तत्र शब्दस्यानिवेशादित्यत आह—उपाधिरहितस्येति। प्रतियोगिरहितस्येत्यर्थः। शब्दशास्त्रत्वाच्च शब्द एव प्रतियोगीति भावः ॥ विरामोऽभावपदार्थोऽपि संबन्धादिवदभावसमानाधिकरणत्वाच्च प्रतियोगिसापेक्ष इति भावः ॥

(११८७ न्यासान्तरवार्तिकम् ॥ ५ ॥)

॥*॥ तत्पर इति वा वर्णस्यावसानम् ॥*॥

(भाष्यम्) विरामपरो वर्णः अवसानसंज्ञो भवतीति वक्तव्यम् ॥

(प्रदीपः) तत्पर इति वेति। इदानीं शब्दान्तराभावपरो वर्णोऽवसानसंज्ञो भवतीति प्रतिपाद्यते अभावेनापि बुद्धिपरिकल्पितं पौर्वापर्यमाश्रीयते ॥

(उद्योतः) बुद्धिकल्पितेति । बुद्धिदेशेऽग्रेऽभावं दृष्ट्वा तत्र कल्पितं पौर्वापर्यमित्यर्थः ॥

(११८८ न्यासान्तरवार्तिकम् ॥ ६ ॥)

॥ * ॥ वर्णोन्त्यो वावसानम् ॥ * ॥

(भाष्यम्) अथ वा व्यक्तमेव पठितव्यम्—अन्त्यो वर्णोऽवसानसंज्ञो भवतीति ॥

(प्रदीपः) अथ वेति । यद्यपि विरामशब्दे करणसाधने आश्रीयमाणेऽयमर्थो लभ्यते, तथापि भावसाधनस्यापि संभवात् करणसाधनत्वं संदिग्धमिति व्यक्तमेव पठितव्यमित्युक्तम् ॥

(तटस्थाक्षेपभाष्यम्)

तत्तर्हि वक्तव्यम्? ॥

(समाधानभाष्यम्)

न वक्तव्यम् ॥

(११८९ प्रत्याख्यानवार्तिकम् ॥ ७ ॥)

॥ * ॥ संहितावसानयोर्लोकविदितत्वात् सिद्धम् ॥ * ॥

(भाष्यम्) संहिता अवसानमिति लोकविदितावेतावर्थौ । एवं हि कश्चित्कंचिदधीयानमाह—'शन्नोदेवीयं संहितयाधीष्व' इति । स तत्र परमसन्निकर्षमधीते । अपर आह—'केनावस्यसि' इति । स आह—अकारेणेकारेणोकारेणेति । एवमेतौ लोकविदितावर्थौ तयोर्लोकविदितत्वात्सिद्धमिति ॥ विरामोवसानम् ॥ १०९ ॥

इति श्रीमद्भगवत्पतञ्जलिविरचिते व्याकरणमहाभाष्ये प्रथमाध्यायस्य चतुर्थे पादे चतुर्थमाह्निकम् ॥

पादोध्यायश्च समाप्तः ॥

(प्रदीपः) संहितयाधीष्वेति । यथा पदनैरन्तर्ये संहिताव्यवहारस्तथैकपद्येऽपि वर्णनैरन्तर्ये । अवसानशब्दोपि विधिप्रदेशेषु भावसाधनः करणसाधनो वा आश्रयिष्यते इति नार्थः संज्ञाद्वयविधानेन तेन विनापीष्टस्य सिद्धत्वात् ॥ १०९ ॥

इत्युपाध्यायजैयटपुत्रकैयटकृते महाभाष्यप्रदीपे प्रथमाध्यायस्य चतुर्थपादे चतुर्थमाह्निकम् ॥

पादोध्यायश्च समाप्तः ॥

(उद्योतः) ननु लोके संहिताशब्दः पदनैरन्तर्ये एव प्रसिद्धो न वर्णनैरन्तर्ये इत्यत आह—यथेति ॥ ऐकपद्ये इति एकपदे इत्यर्थः ॥ भावसाधन इति । अत्र पक्षे खरवसानयोरित्यत्र बौद्धं पौर्वापर्यमाश्रयणीयमिति शिवम् ॥ १०९ ॥

इति श्रीकालोपनामकशिवभट्टसुतसतीगर्भजनागोजी(नागेश)-भट्टकृते भाष्यप्रदीपोद्योते प्रथमस्य चतुर्थे चतुर्थमाह्निकम् ॥

पादोऽध्यायश्च समाप्तः ॥ १ ॥ शुभम् ॥

श्रीदधिमती(थी) जयति ॥

अथ द्वितीयाध्यायस्य प्रथमे पादे प्रथममाह्निकम् ।

(२२१ समर्थपरिभाषासूत्रम् ॥ २।१।१ आ. १ सू.)

३५० समर्थः पदविधिः ॥ २।१।१ ॥

(अथ विधिशब्दार्थनिरूपणाधिकरणम्)

(आक्षेपभाष्यम्)

विधिरिति कोयं शब्दः ? ॥

(प्रदीपः) **समर्थः पदविधिः ॥ १ ॥ विधिरिति कोयं शब्द इति** । अर्थानिश्चयात् संदेहे सति प्रश्नः । किं भावसाधनः, उत कर्मसाधनः । तत्र भावसाधने पदानां विधीयमानत्वात् कर्मणि षष्ठी । इतरत्र शेषषष्ठी ॥ तत्र येषामर्थभेदाच्छब्दभेद इति दर्शनं सादृश्यनिबन्धना च प्रत्यभिज्ञा, तद्दर्शने क इति प्रश्नो विशिष्टशब्दनिर्धारणाय । ये त्वर्थभेदेपि शब्दस्यैक्यमिच्छन्ति तत्पक्षेऽर्थभेदाच्छब्दभेदमारोप्य क इतिप्रश्नः ॥

(उद्योतः) **समर्थः पद** ॥ १ ॥ विधिरिति **कोयमिति** भाष्यस्य न स्वरूपप्रश्ने तात्पर्यं तस्य श्रोत्रेण निश्चितत्वादित्यतोऽभिप्रायमाह—**अर्थेति** ॥ **कोयमित्यस्य** किमर्थकोयमित्यर्थः ॥ शब्दार्थयोरभेदादिति भावः ॥ **किं भावेति** । करणाधिकरणसाधनस्त्वनन्वितत्वात् प्रयोजनाभावाच्च नोल्लिखितः ॥ **विधीयमानत्वादिति** । वत्साद्विधाविति शेषः ॥ **इतरत्रेति** । कर्मसाधने इत्यर्थः ॥ अर्थभेदाच्छब्दभेद इति मते प्रत्यभिज्ञानुपपत्तिः तद्भेदेपि शब्दैक्ये तु कः शब्द इत्यनुपपन्नमत आह—**तत्रेति** ॥

(समाधानभाष्यम्)

विपूर्वाद्धाञः कर्मसाधन इकारः–विधीयते विधिरिति ॥ किं पुनर्विधीयते? ॥ समासो विभक्तिविधानं पराङ्गवद्भावश्च ॥

(प्रदीपः) **विपूर्वादिति** । 'विध विधाने' इत्यस्यौणादिकेन्प्रत्ययान्तस्य निवृत्त्यर्थं **विपूर्वाद्धाञ** इत्युक्तम् । स्वरे चानयोर्भेदः । इन्प्रत्ययान्तस्याद्युदात्तत्वात् किप्रत्ययान्तस्यान्तोदात्तत्वात् ॥ तस्यैव प्रयोगदर्शनमुत्तरे हेतुः ॥ **कर्मसाधन इति** । एतद्भावसाधननिवृत्त्यर्थमुक्तम् ॥ **विधीयत इति** वाक्यप्रदर्शनं सुखप्रतिपत्त्यर्थम् ॥ **किं पुनरिति** । कार्यविशेषस्येहानिर्देशात् प्रश्नः ॥ इतरो वक्ष्यमाणान् कार्यविशेषान् पर्यालोच्याह—**समास इति** । अनन्तरस्यापि **पराङ्गवद्भाव**स्याल्पविषयत्वादनादरात्तन्निमित्तग्रहणेनाचातिप्रसङ्गनिरासस्य सिद्धत्वात् मुख्यप्रयोजनत्वाभावात् पश्चान्निर्देशः कृतः । तत्र **समास**शब्देन संज्ञा वोच्यते समुदायो वा संज्ञी । **विभक्तिविधान**शब्देन सामान्यविहितानां विभक्तीनां **कर्मणि द्वितीये**त्यादिना यो नियमः स उच्यते । एवं हि पदविधिर्भवति । अथाप्येकवाक्यताश्रयणेन विभक्तीनां विधानं तथापि पदान्तरसंबन्धेन यासां विभक्तीनां विधान**मन्तरान्तरेणयुक्त** इति, तिङ्विभक्तीनां **नेर्विश** इति, तदाश्रयेण पदविधित्वमस्त्येव । तथा चोक्तम्—**निरपि पदं विशिरपि पदमिति** । तत्र विभक्त्यवच्छिन्नत्वाद्विशिष्टं विधानं कर्म सामान्यविधानक्रियाया भवति । यथोक्तम्—**सामान्यपुषेरवयवपुषिः कर्मेति** ॥

(उद्योतः) **औणादिकेनेति** । इगुपधात्किदित्यनेनेति भावः ॥ **स्वरे चेति** । बहुलग्रहणादौणादिकस्यापि कर्मणि संभव इति भावः ॥ **प्रयोगदर्शनमिति** । त्रैस्वर्येणाष्टाध्यायीपाठादिद वेदे लोके चेति शेषः ॥ **एतद्भावेति** । तथा सति पदकर्मके विधाने इत्यर्थापत्तौ समासाद्यसंग्रहः स्याद्, वत्साद्यादेशविधौ चातिप्रसङ्गः स्यादिति भावः ॥ **इह**, सूत्रे ॥ **इतर इति** । प्रकरणपर्यालोचनयेति भावः ॥ समासपदं वृत्तिमात्रोपलक्षणम् ॥ **समुदायो वेति** । स अवयवभूतपदानां कार्यः, समूहस्यावयवातिरिक्तताया अपि स्वीकारादिति भावः ॥ विभक्त्यन्तस्य पदत्वाद् विभक्तिविधानस्य कथं पदोद्देश्यकविधित्वमित्याशङ्क्याह—**विभक्तीति** ॥ **एवं हीति** । विहितानां नियमस्य विधिना पक्षप्राप्तेतरविभक्त्यन्तानां निवृत्तिरूपस्याश्रयणेन सा निवृत्तिः पदोद्देश्यिकेत्यर्थः ॥ केचित्तु पदोद्देश्यकः पदत्वसंपादको वा सर्वोपि पदसंबन्धित्वात्पदविधिरेवेति वदन्ति ॥ ननु किं **विधीयत** इति प्रश्ने **विभक्तिविधान**मित्युत्तरमयुक्तं विधानस्य विधानकर्मत्वाभावादत आह—**तत्र विभक्त्यवेति** । एवं च पाकं पचतीतिवत् सामान्यविशेषभावेनान्वय इति भावः । क्रियाविशेषणत्वाच्च कर्मत्वम् ॥

(इति विधिशब्दार्थनिरूपणम्)

—•○•—

(परिभाषात्वनिरूपणाधिकरणम्)

(आक्षेपभाष्यम्)

किं पुनरयमधिकारः, आहोस्वित् परिभाषा ? ॥

(प्रदीपः) कार्यविशेषानिर्देशादस्य पारार्थ्यमवगत्य परार्थेषु रूपद्वयं दृष्ट्वा पृच्छति—**किं पुनरिति** ॥ नन्वधिकारेस्मिन् पदविधिग्रहणमनर्थकम् । उत्तरेषां पदविधित्वाव्यभिचारात् । तस्मात् पदविधिग्रहणात् परिभाषात्वनिश्चयात् प्रश्नानुपपत्तिः ॥ एवं तर्हि युक्तायुक्तत्वापेक्षया प्रश्नः । तत्र यद्यधिकारपक्षस्य युक्तत्वं तदा न कर्तव्यं पदविधिग्रहणम् । परिभाषाया युक्तत्वे कर्तव्यम् । अधिकारपक्षेपि वा विस्पष्टार्थं भविष्यति ॥

(उद्द्योतः) रूपद्वयमिति । यद्यपि संज्ञात्वमपि तत्र, तथाप्येतद्रूपया तया शास्त्रे व्यवहाराभावात्तन्नोक्तम् ॥

(प्रत्याक्षेपभाष्यम्)

कः पुनरधिकारपरिभाषयोर्विशेषः ? ॥

(प्रदीपः) **कः पुनरिति** । अन्योत्र प्रष्टा विज्ञेयः ॥ आद्येन तु तद्विशेषज्ञेन भवितव्यम् । अन्यथा **किं पुनरयमधिकार** इति प्रश्नो नोपपद्यते ॥

(उद्द्योतः) **अन्येनेति** । पूर्वपक्षिणा सिद्धान्तिना चेत्यर्थः ॥ आद्येनेति पाठे **किं पुनरिति** सन्देहकर्त्रेत्यर्थः ॥ **अन्यथा** । अधिकारपरिभाषयोर्विशेषाज्ञाने ॥

(प्रत्याक्षेपसमाधानभाष्यम्)

अधिकारः प्रतियोगं तस्यानिर्देशार्थ इति योगेयोगे उपतिष्ठते ॥ परिभाषा पुनरेकदेशस्था सती कृत्स्नं शास्त्रमभिज्वलयति प्रदीपवत् । तद्यथा— प्रदीपः सुप्रज्वलित एकदेशस्थः सर्वं वेश्माभिज्वलयति ॥

(प्रदीपः) **अधिकारः प्रतियोगमिति** ॥ स्वरूपे पृष्टे फलाख्यानं तद्द्वारेण स्वरूपावबोधार्थम् । अधिक्रियमाणस्य हि प्रतियोगमुपस्थाने सति तदनिर्देशः फलं संपद्यते ॥ **परिभाषा पुनरिति** । लिङ्गोपादानेन परिभाषा क्रियमाणा यत्रयत्र तल्लिङ्गोपलम्भस्तत्तद्व्याप्नोतीत्यर्थः । प्रदेशान्तरेषु तु परार्थतासामान्यादधिकारपरिभाषयोरभेदेन व्यवहारो भाष्यकारस्य **अधिकारो नाम त्रिःप्रकार** इति । तथा **द्वयोः परिभाषयोः सावकाशयोः समुपस्थितयोरिति** ॥

(उद्द्योतः) **फलाख्यानम्** । तस्यानिर्देशार्थ इत्येतत् ॥ **स्वरूपम्** । योगेयोगेऽनुपस्थितिरूपम् ॥ **लिङ्गोपादानेनेति** । स्वरितत्वप्रयुक्ताधिकारेणोत्तरत्र तत्तत्पदोपस्थितिरधिकारान्तरं दृष्ट्वा व्याख्यानाद्वा निवृत्तिश्च । परिभाषायास्तु लिङ्गवति सर्वत्र तेषां सर्वेषामत्रोपस्थित्या परिभाषाया वा तत्रतत्रोपस्थित्या स्वार्थोपस्थितिद्वारा व्याप्तिरिति भावः ॥ इदं च **षष्ठी स्थाने** इति सूत्रे निरूपितम् । तदुक्तम्—

> "एकदेशस्थिता शास्त्रभवने याति दीपताम् ।
> परितो व्यापृतां भाषां परिभाषां प्रचक्षते" ॥

प्रदेशान्तरेष्विति । **षष्ठी स्थाने** इति सूत्रे आद्यं, **निपात एकाजनाङि**त्यत्र चान्त्यम् । तत्र च पारार्थ्यसामान्यादतिदेशसंज्ञयोः परिभाषात्वेन व्यवहार इति बोध्यम् ॥

(प्रत्याक्षेपान्तरभाष्यम्)

कः पुनरत्र प्रयत्नविशेषः ? ॥

(प्रदीपः) **कः पुनरत्रेति** । कस्मिन् पक्षे यत्नस्य लाघवं भवति, कस्मिन् वा गौरवमिति प्रश्नः ॥

(प्रत्याक्षेपान्तरसमाधानभाष्यम्)

अधिकारे सति स्वरयितव्यम् । परिभाषायां तु सर्वमपेक्ष्यम् ॥

(प्रदीपः) **स्वरयितव्यमिति** । स्वरितगुणयुक्तं समर्थग्रहणं पठितव्यमित्यर्थः । तत्र स्वरितो गुणः क्रियारूपेण स्वरयितव्यमिति निर्दिष्टः यथा श्वेतो गुणः श्वेतते इति । पदविधिग्रहणं चात्र पक्षे न कर्तव्यमित्यर्थादुक्तं भवति ॥ **सर्वमपेक्ष्यमिति** । यावन्ति पदकार्याणि तानि सर्वाण्यपेक्ष्य पदविधिशब्दोपादानेन च परिभाषा कर्तव्येत्यर्थः । अन्यास्वपि परिभाषासु यल्लिङ्गमुपादीयते तल्लिङ्गयुक्तापेक्षा क्रियते ॥

(उद्द्योतः) **स्वरितगुणयुक्तमिति** । स्वरवच्छब्दाद्वात्वर्थे णिचि मतोर्लुकि टिलोपाभावेप्यङ्गवृत्तपरिभाषया वृद्ध्यभावे आद्गुणे रूपमिति भावः ॥ यद्वाऽर्शआद्यजन्तस्वरशब्दाद् णिचीदं रूपम् ॥ **यावन्तीति** । भाष्ये **सर्व**मित्यस्य लिङ्गवत्सर्वं शास्त्रमित्यर्थः । **तानि सर्वाणि** पदविधिशब्दोपादानेन सामान्यतः पदविधित्वेन । **अपेक्ष्य** अनूद्येत्यर्थः ॥

(संदेहान्तरभाष्यम्)

तथेदमपरं द्वैतं भवति—एकार्थीभावो वा सामर्थ्यं स्यात्, व्यपेक्षा वेति ? ॥

(प्रदीपः) **द्वैतमिति** । द्वयोर्भावो द्विता तत्र भवं द्वैतं संशयरूपं ज्ञानमुच्यते । अथ वा द्वाभ्यामितं प्रकारद्वयेन विरुद्धत्वाद्भिन्नाधारवर्तिना युक्तं वस्तु द्वीतं तत्र भवं द्वैतं तदेव संशयज्ञानम् ॥ **एकार्थीभाव इति** ॥ यत्र पदान्युपसर्जनीभूतस्वार्थानि निवृत्तस्वार्थानि वा प्रधानार्थोपादानाद्यर्थानि, अर्थान्तराभिधायीनि वा स **एकार्थीभावः** ॥ परस्पराकाङ्क्षारूपा **व्यपेक्षा** ॥

(उद्द्योतः) **द्वयोर्भावो द्वितेति** । कोटिद्वये सत्येव संशयोदयाद् द्वित्वभवः संदेह इति भावः ॥ द्विविषयनिश्चयस्यापि द्वित्वभवत्वादाह—**अथ वेति** । विरुद्धत्वाद्भिन्नाधारवर्तिना प्रकारद्वयेन युक्तमित्यन्वयः । परस्परविरुद्धधर्मद्वयवद्वस्तुद्वयमित्यर्थः ॥ अनेकार्थस्यैकार्थत्वमेकार्थीभाव इति शब्दशक्तिमनुसृत्य जहत्स्वार्थाजहत्स्वार्थयोस्तं दर्शयिष्यन्नादावजहत्स्वार्थायां तं दर्शयति—**यत्र पदानीति** ॥ उपसर्जनपदानीत्यर्थः ॥ तदेव ध्वनयन्नाह—**उपसर्जनभूतस्वार्थानीति** । इतरविशेषणभूतस्वार्थोपस्थापकानीत्यर्थः । न तु पृथक्स्वार्थोपस्थापकानीति तात्पर्यम् । एवं च तत्पुरुषादावेकं पदं तादृशम्, बहुव्रीहौ द्वन्द्वे च पदद्वयमपीति बोध्यम् ॥ जहत्स्वार्थामाह—**निवृत्तस्वार्थानि वेति** । उभयत्रापि हेतुः—**प्रधानार्थोपादानादिति** । आद्ये प्रधानार्थेन स्वोपस्थितिकाले एवोपसर्जनपदार्थस्य विशेषणतयोपादानादित्यर्थः । अन्त्ये प्रधानेन पदेन तदर्थस्याप्युपादानादित्यर्थः । बहुव्रीहौ तु प्रधानं पदं समुदाय इति बोध्यम् ॥ एवं द्वन्द्वेऽपि प्रधानं पदं समुदायस्तदर्थेन साहित्येन ...

स्वविशेषणतया धवाद्यर्थस्योपादानादुपसर्जनभूतस्वार्थानि । यद्वा विशेष्यसाहित्योपस्थापकतया प्रधानेन समुदायेनैव धवाद्यर्थस्याप्युपादानान्निवृत्तस्वार्थानि वेति । तत्राप्ययमेकार्थीभावः समाहारेतरेतरयोगयोरुभयोरपि साहित्यं विशेष्यम्। आद्येऽनुद्भूतावयवभेदमन्त्ये उद्भूतावयवभेदमित्येव तयोर्भेद इति बोध्यम् ॥ **व्यर्थानीति**। संनिहितत्वान्निवृत्तस्वार्थानीत्येतत्पक्षान्वयि ॥ आद्ये आह—**अर्थान्तरेति**। अर्थान्तरान्वितस्वार्थाभिधायीनीत्यर्थः । प्रत्येकशक्तिग्रहकृतसमुदायशक्त्या विशिष्टार्थप्रतिपादकानीति भावः ॥ **पदानीति**। बहुवचनं तु बहुव्रीह्याद्यभिप्रायेण ॥ **स एकार्थीभाव इति**। आद्ये एकीभूतार्थानि मिलितार्थानीत्यर्थः । तत्र मिलनस्येतरसाकाङ्क्षत्वाद् द्वयोरपि समर्थत्वं तत्पुरुषादौ । अन्त्ये पदद्वयार्थयोरेकपदार्थत्वप्राप्तिरित्यर्थः ॥ **परस्परेति**। विशब्दस्य क्रियाव्यतीहारवृत्तित्वादिति भावः ॥

(एकार्थीभावव्यपेक्षयोर्विशेषप्रदर्शकभाष्यम्)

तत्रैकार्थीभावे सामर्थ्येऽधिकारे च सति समास एकः संगृहीतो भवति। विभक्तिविधानं पराङ्गवद्भावश्चासंगृहीतः॥

व्यपेक्षायां पुनः सामर्थ्येऽधिकारे च सति विभक्तिविधानं पराङ्गवद्भावश्च संगृहीतो भवति। समासस्त्वेकोऽसंगृहीतः॥ अन्यत्र खल्वपि समर्थग्रहणानि युक्तग्रहणानि च कर्तव्यानि भवन्ति॥ क्वान्यत्र?। "इसुसोः सामर्थ्ये" "न चवाहाहैवयुक्ते" इति॥

व्यपेक्षायां पुनः सामर्थ्ये परिभाषायां च सत्यां यावान् व्याकरणे पदगन्धो नाम स सर्वः संगृहीतो भवति। समासस्त्वेकोऽसंगृहीतः॥

(प्रदीपः) **समास एक इति**। तत्रैवैकार्थीभावस्य सद्भावात् ॥

(उद्योतः) **तत्रैवैकार्थीभावस्येति**। तदुक्तत्रयाणां मध्ये तत्रैवेत्यर्थः ॥ व्यपेक्षासहिताधिकारत्वेऽधिकारत्वप्रयुक्तदोषमाह— भाष्ये—**अन्यत्र खल्वपीति**॥ एकार्थीभावसहिताधिकारत्वेऽधिकारत्वप्रयुक्तो दोषस्तु मध्ये पादद्वये निवृत्त्या तृतीयाध्यायादावसंबन्धो बोध्यः ॥ एतेनाधिकारत्वसहितोभयविधसामर्थ्याश्रयणपक्षोपि निरस्तः ॥

(सिद्धान्तभाष्यम्)

तत्रैकार्थीभावः सामर्थ्यं परिभाषा चेत्येवं सूत्रमभिन्नतरकं भवति॥

(प्रदीपः) **तत्रेति**। एकार्थीभावः सामर्थ्यमधिकार इत्येकः पक्षः। व्यपेक्षा सामर्थ्यमधिकार इति द्वितीयः पक्षः। द्विविधं सामर्थ्यमधिकार इति तृतीयः। एवं परिभाषायामपि त्रयः पक्षा इति षट्पक्षीसंभवे एकार्थीभावः परिभाषा चेति निर्णयः ॥ **अभिन्नतरकमिति**। उभयविधे सामर्थ्ये आश्रीयमाणेऽर्थस्य भेदात् सूत्रस्य भेदः स्यात्। भिन्नेन सामर्थ्येन भिन्नेषु वाक्येषु उपस्थानात् ॥ व्यपेक्षायामपि सामर्थ्ये यद्यपि सूत्रमभिन्नं भवति, तथाप्येकार्थीभावे सामर्थ्ये दोषाभावात् प्रकर्षयोगादभिन्नतरकमित्युच्यते ॥ तत्र पराङ्गवद्भावे तन्निमित्तग्रहणाद्दोषाभावः। विभक्तिविधानेपि कारकविभक्तिषु क्रियाकारकयोर्व्यपेक्षाऽविनाभावित्वादुपपदविभक्तिषु युक्तयोगग्रहणसद्भावात् क्वचित् तृतीयया योगस्याक्षेपादेतदनुपस्थानेपि न दोषः। परिभाषायां च सुब्धातुप्रभृतयः सर्वा वृत्तयः संगृहीता भवन्ति। एकार्थीभावे चेहाश्रितेऽन्यत्र युक्तग्रहणं समर्थग्रहणं च कृतमेवेति तत्रापि न दोषः ॥

(उद्योतः) **उभयविधे इति**। अधिकारत्वे परिभाषात्वे चेत्यर्थः ॥ **भेदो**, वैरूप्यलक्षणः ॥ ननु पराङ्गवद्भावविधानासंग्रहो दोषोऽस्त आह—**तत्रेति** ॥ **व्यपेक्षाऽविनाभावित्वादिति**। व्यपेक्षाया नियतत्वादित्यर्थः। एवं चैतदुपस्थितिं विनापि तत्र न दोषः, क्रियाकारकयोरेकार्थीभावासंभवश्चेति भावः ॥ अत्र क्रियाकारकयोरित्युक्त्या प्रकृत्यर्थविभक्त्यर्थयोः सर्वथा व्यपेक्षाभावो दर्शितः ॥ इदानीमेकार्थीभावसहितपरिभाषापक्षे उक्तं प्रकर्षयोगमुपपादयति—**सुब्धातुप्रभृतय इति**। एतेनाधिकारत्वे एतदसंग्रहो दोष इति ध्वनितम् ॥ **अन्यत्र युक्तग्रहणमिति**। तथा च तदेवात्रैकार्थीभावसामर्थ्याश्रयणे लिङ्गमिति भावः ॥

(आक्षेपभाष्यम्)

एवमपि क्वचिदकर्तव्यं समर्थग्रहणं क्रियते। क्वचिच्च कर्तव्यं न क्रियते। अकर्तव्यं तावत्क्रियते—"समर्थानां प्रथमाद्वा" इति। कर्तव्यं न क्रियते—"कर्मण्यण्" समर्थादिति॥

(प्रदीपः) **समर्थानामिति**। **घकालतनेषु कालनाम्न** इत्यलुग्विधानाल्लिङ्गाद्विभक्त्यन्तात् तद्धित उत्पद्यते इति पदविधित्वादेतत्परिभाषोपस्थितौ असामर्थ्ये प्रत्ययाप्रसङ्गात् ॥ **कर्मण्यणिति**। पञ्चकप्रातिपदिकार्थपक्षे प्रातिपदिकेनैव कर्मण उपादानान्नास्ति पदविधित्वम्। त्रिकादिपक्षे तु विभक्तिवाच्यत्वात् कर्मणः पदविधित्वादेतत्परिभाषोपस्थानान्नास्ति दोषः ॥

(उद्योतः) **समर्थानां प्रथमा**दित्यत्र समर्थपदस्य कृतसन्धिकार्यार्थकत्वमजानान आह—**एवमपि क्वचिदिति** ॥ **लिङ्गादिति**। एतल्लिङ्गमूलकात्कुत्सितशतिसूत्रभाष्योक्तन्यायादित्यर्थः। कृतसन्धिकार्यत्वार्थकमपि तत्र तदर्थम्, सौत्थितावन्तरङ्गत्वेनैव पूर्वं सन्धिकार्यप्रवृत्तेर्विप्रतिषेधपक्षे भाष्ये उक्तत्वात् ॥ **पञ्चकेति**। इदं चिन्त्यम्। तत्पक्षेपि तदर्थद्योतकतया विभक्तेरावश्यकत्वात् ॥ भाष्ये पूर्वपक्षाशयस्त्वेवं पदविधिशब्देन पदोद्देश्यकविधिग्रहणम्। एवं च साक्षात्पदोद्देश्यके समासतद्धितादावेव स्यात्त्वत्र। अत्र हि यः संख्यानुदेश्यो धातुर्न स पदम्। किं च धातोरण्

कर्म चोपपदसंज्ञमिति सूत्रार्थात्सन्नियोगशिष्टन्यायेन तत्र सति प्रत्यय इति न तदुद्देश्यकः प्रत्ययविधिः। उपपदसंज्ञायास्तदुद्देश्यकत्वेपि तत्रैकार्थीभावयोग्यद्वितीयाभाव इति॥

(आक्षेपसाधकभाष्यम्)

ननु च गम्यते तत्र सामर्थ्यं कुम्भकारो नगरकार इति॥

(प्रदीपः) **ननु चेति।** यदि कुम्भकारशब्दः समर्थाभिधायी चासमर्थाभिधायी च स्यात् ततोऽसमर्थाभिधायिप्रयोगनिवृत्त्यर्थो यत्नः कर्तव्यः स्यान्न त्वन्यथेत्यर्थः॥

(उद्द्योतः) देवदत्तस्य कुम्भं करोतीत्यादौ प्रत्ययनिवृत्तये समर्थग्रहणस्यावश्यकत्वात्किमुच्यते **गम्यते तत्र सामर्थ्यमित्यत आह—यदीति।** प्रयुक्तानामिदमन्वाख्यानं लोकप्रयुक्तासाधोरेव निवर्तकमिति न दोष इति भावः॥

(आक्षेपसमाधानभाष्यम्)

सत्यम्। गम्यते उत्पन्ने हि प्रत्यये। स एव तावत्समर्थादुत्पाद्यः॥

(प्रदीपः) **स एव तावदिति।** यथा समासादयोऽसमर्थानां मा भूवन्नित्येवमर्थमिदं वचनं क्रियते तद्वदत्रापि समर्थग्रहणमसामर्थ्ये प्रत्ययनिवृत्त्यर्थं कर्तव्यमित्यर्थः। प्रतिविधानं तु सुज्ञानत्वाद्भाष्यकृता नोक्तम्। यत उपपदमिति महत्याः संज्ञायाः करणं प्रत्ययस्य पदाश्रयत्वे सति समर्थपरिभाषाव्यापारार्थमेव॥

(उद्द्योतः) भाष्ये—**उत्पन्ने हीति** हिस्त्वर्थे॥ **यथा समासादय इति।** अन्यथात्रापि तद्वैयर्थ्यं स्यात्। प्रयुक्ताप्रयुक्तत्वविवेकरहितानामर्थे इहेव तत्रापि कर्तव्यमित्यर्थः॥ **महत्याः संज्ञाया इति।** संज्ञासूत्रस्थतत्रग्रहणस्य चेत्यपि बोध्यम्। यथाकथंचित्पदसंबन्धिविधिस्तत्र ग्रहणमिति भावः॥

(इति परिभाषात्वनिरूपणम्)

(अथ समर्थपरिभाषाप्रयोजनाधिकरणम्)

(आक्षेपभाष्यम्)

अथ समर्थग्रहणं किमर्थम्?॥

(प्रदीपः) **अथेति।** प्रधानपर्यनुयोगद्वारेण सूत्रस्यैवाक्षेपः। यद्यप्यनेन सामर्थ्यं न विधीयते नहि स्वतोऽसमर्थस्य सामर्थ्यं वचनेन कर्तुं पार्यते। तथापि पदविधौ सामर्थ्योपस्थानार्थत्वाद् अस्य समर्थपदस्य प्राधान्यमुच्यते॥

(उद्द्योतः) **न विधीयत इति।** एवं च न तस्य प्रधानत्वमिति भावः॥ सामर्थ्योपस्थानं, समर्थपदोपस्थानम्॥

(समाधानभाष्यम्)

वक्ष्यति—'द्वितीया श्रितादिभिः समस्यते' कष्टश्रितो नरकश्रित इति॥ समर्थग्रहणं किमर्थम्?। पश्य देवदत्त कष्टं, श्रितो विष्णुमित्रो गुरुकुलम्॥

"तृतीया तत्कृतार्थेन गुणवचनेन" उपादानविकलः, शङ्कुलाखण्डः, किरिकाणः॥ समर्थग्रहणं किमर्थम्? त्वं तिष्ठ शङ्कुलया, खण्डो धावति मुसलेन। किं त्वं करिष्यसि शङ्कुलया, खण्डो विष्णुमित्र उपलेन॥

"चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः"। गोहितम्। वृषभहितम्। अश्वहितम्॥ समर्थग्रहणं किमर्थम्?। सुखं गोभ्यो, हितं देवदत्ताय॥

"पञ्चमी भयेन" वृकभयं दस्युभयं चोरभयम्॥ समर्थग्रहणं किमर्थम्?। गच्छ त्वं मा वृकेभ्यो, भयं देवदत्ताद्यज्ञदत्तस्य॥

'षष्ठी सुबन्तेन समस्यते'। राजपुरुषः। ब्राह्मणकम्बलः॥ समर्थग्रहणं किमर्थम्?। भार्या राज्ञः, पुरुषो देवदत्तस्येति॥

"सप्तमी शौण्डैः" अक्षशौण्डः स्त्रीशौण्डः॥ समर्थग्रहणं किमर्थम्?। कुशलो देवदत्तोऽक्षेषु, शौण्डः पिबति पानागारे॥

(प्रदीपः) **समस्यत इति।** यद्यपि समाससंज्ञामात्रं विधीयते। तथाप्यबुधबोधनाय भिन्नयोः शब्दयोः संश्लेषः प्रक्रियायां क्रियत इति समस्यत इत्युक्तम्॥ **पश्येति।** असति सूत्रे द्वितीयान्तमात्रं श्रितादिभिः समस्येताविरोधात्। एकार्थीभावाभावेपि वचनात् समाससंज्ञा स्यात्। अनर्थकस्यापि च समासस्य वचनात् प्रातिपदिकसंज्ञा स्यात्। विध्यर्थत्वसंभवे च समासग्रहणस्य नियमार्थत्वानुपपादनाद्वाक्यस्य प्रातिपदिकसंज्ञानिषेधः कर्तव्य एव स्यात्। एकार्थीभावाभावेपि चोत्तरपदार्थस्य बाह्यसंबन्धिनं प्रति योग्यत्वाद्दानाद्विभक्तयः स्युरेव॥ **खण्डो धावतीति।** तृतीयान्तार्थकृतत्वमत्रास्तीति समासः स्यात्॥

(उद्द्योतः) पश्य देवदत्त कष्टमिति कष्टपदार्थमाह—**श्रित इति॥** नन्वसत्यपि समर्थग्रहणे एकार्थीभावाभावेऽनर्थकत्वेन प्रातिपदिकसंज्ञाऽप्रवृत्तौ फलाभावात्समासोपि न स्यात् सूत्रं त्वेकार्थीभाववति चरितार्थमित्यत आह—**असति सूत्रे इति॥** नन्वेकार्थीभावविषये एव समासः शिष्टैः प्रयुज्यते इति कथमेतदत आह—**वचनादिति॥** लक्षणमात्रशरणं प्रति सूत्रारम्भ इति भावः॥ ननु फलाभावोऽत आह—**वचनादिति। कृत्तद्धितेतिवचनादित्यर्थः॥ बाह्यसंबन्धिनमिति।** विष्णुमित्रादयो बाह्यसंबन्धिनः॥ भाष्ये—**उपादानविकल इति।** उपादानेन कृतो विकल इत्यर्थः॥ **तिष्ठ त्वमिति।** तिष्ठ त्वं शङ्कुलया न प्रयोजनं मुसलेन कृतः खण्डो धावतीत्यर्थः॥ **शङ्कुलयेति** सहयोगे तृतीयेत्यपि कश्चित्। हे विष्णुमित्र त्वं शङ्कुलया किं करिष्यस्युपलेन पाषाणेन कृतः खण्ड इति द्वितीयार्थः॥ ननु खण्डस्य

प्रकृततृतीयान्तार्थकृतत्वं नास्तीत्यत आह—तृतीयान्तार्थेति । तच्छब्देन तृतीयान्तमात्रं परामृश्यते तस्यात्र खण्डनस्य करणसाध्यत्वावश्यम्भावादवश्यमस्त्येवेति भावः । प्रत्यासत्तिर्नाश्रीयत इत्यभिप्रायः ॥ वृकेभ्य इत्यस्य मा भैषीरिति क्रियां प्रत्यपादानत्वं यज्ञदत्ताद्देवदत्तोऽवश्यं रक्ष्य इति मार्गे संभावितमपि वृकभयं त्यक्त्वा तद्रक्षणार्थं त्वं गच्छेति वाक्यार्थः ॥

(आक्षेपभाष्यम्)

अथ क्रियमाणेपि समर्थग्रहणे इह कस्मान्न भवति-महत्कष्टं श्रित इति ? ॥

(प्रदीपः) **महत्कष्टमिति ।** अस्त्येवात्र श्रयणक्रियया सामर्थ्यमिति प्रश्नः ॥ यद्यत्र कष्टश्रितशब्दयोः समासः स्यात्तदा महत्कष्टश्रित इति स्यात् । अथापि त्रयाणां पदानां समासः स्यात्तथाप्युत्तरपदे विधीयमानमात्वं मध्यमपदे न स्यात् । अथापि त्रयाणां समासे कृते **सन्महदिति** द्वयोः समासः । य एव च महाकष्टं श्रितो महाकष्टश्रित इत्यत्राहीने **द्वितीयेति** स्वरो भवति, तत्र स एव **समासस्येत्य**नेन, तथापि महारण्यातीत इत्यत्र स्वरो भिद्यते । महारण्यमतीत इति द्विपदे समासे कृते **थाथादि**स्वरः, त्रिपदे तु समासे कृते **सन्महदिति** द्वयोस्तत्पुरुषे कृते सति महारण्यशब्दः समासस्वरेणान्तोदात्तः स्यात् । यथा पूर्वशालाप्रिय इत्यत्र शालाशब्द उदात्तः ॥ अन्येत्वाहुः—त्रयाणां समासे कृते प्रधानार्थाभिधायित्वान् महत्कष्टशब्दयोः परस्परसंबन्धाभावात् पूज्यमानत्वं विशेषणविशेष्यत्वं च नास्तीति समासो न स्यात् ततश्चात्त्वं न स्यात् । **अहीने द्वितीयेति** महच्छब्दस्य प्रकृतिस्वरश्च प्रसज्येत ॥

(उद्द्योतः) **अस्त्येवात्रेति ।** सर्वेषां कारकाणां साक्षात्परम्परया वा क्रियायामन्वयादिति भावः ॥ भाष्ये **इह कस्मान्नेति ।** समास इति शेषः ॥ ननु यदि सामर्थ्यमस्ति, अस्तु समासः को दोष इत्यत आह—**यद्यत्रेति** ॥ तदा **महत्कष्टेति** । महदिति पृथक् पदम् ॥ **महाकष्टं श्रित इति ।** एतद्विग्रहके समासे य एवाहीने **द्वितीयेत्यनेन** पूर्वपदप्रकृतिस्वरे हकाराकार उदात्तः, त्रिपदसमासेऽवान्तरतत्पुरुषे तस्य समासान्तोदात्तत्वेपि स एवेत्यर्थः ॥ **समासस्येत्यनेनेति** । अवान्तरतत्पुरुषनिमित्तकेनेत्यर्थः ॥ **थाथादिस्वर इति ।** क्तप्रत्ययाकार उदात्त इत्यर्थः । तेनान्तोदात्तविधानात् ॥ **यथेति** । तत्र हि त्रिपदे बहुव्रीहाववान्तरतत्पुरुषे **तद्धितार्थेत्यनेन** जाते सति शिष्टत्वाद्वावान्तरतत्पुरुषयुक्तः स्वर इत्यर्थः ॥ परे तु महान्देवदत्तः प्रियो यस्येति त्रिपदबहुव्रीहौ महादेवदत्तप्रिय इत्यस्याभावाय महद्देवदत्तप्रिय इत्यस्य सिद्धये त्रिपदसमासेऽवान्तरपदयोः **सन्महदिति** समासाप्रवृत्तिर्बहुलग्रहणादिति महत्कष्टश्रित इत्येवैकपद्येनैकस्वरः स्यात्तच्च नेष्यत इति भाष्याभिप्रायः ॥ **विशेषणं विशेष्येणेत्यस्य** त्रिपदे समासेऽवान्तरपदयोरप्रवृत्तिं सूत्रशेषे वदता तत्प्रपञ्चभूतानां पूर्वनिपातनियमार्थानां च तत्राप्रवृत्तिरुक्तप्रायैवेत्याहुः ॥ **परस्परं संबन्धाभावादिति ।** पृथगेकार्थीभावाभावादित्यर्थः ॥ **पूज्यमानत्वमिति ।** कष्टेन महत्त्वस्यान्वयाभावादिति भावः ॥ **विशेषणविशेष्यत्वं चेति ।** अन्येनैकार्थीभावादेव परस्परं तस्याभाव इत्यर्थः ॥ **समासो न स्यादिति ।** अवान्तरतत्पुरुषो न स्यादित्यर्थः ॥ **स्वरश्च प्रसज्येतेति ।** सौवरीणां सप्तमीनां तदन्तसप्तमीत्वादहीनवाचिक्तान्तोत्तरपदान्तस्य समासस्य संबन्धि द्वितीयान्तं पूर्वपदं प्रकृत्येत्यर्थादिति भावः ॥ अत्रारुचिबीजं तु त्रयाणामेकार्थीभावे द्वयोरपि सोस्त्येव पृथगेकार्थीभावाभावेपि न क्षतिरिति ॥

(प्रत्याक्षेपभाष्यम्)

न वा भवति महाकष्टश्रित इति ? ॥

(प्रदीपः) **न वा भवतीति ।** यथा भार्या राज्ञः पुरुषो देवदत्तस्येत्यत्रात्यन्तमसमासो, नैवमिहेति भावः ॥

(प्रत्याक्षेपसमाधानभाष्यम्)

भवति, यदैतद्वाक्यं भवति—महत्कष्टं महाकष्टं महाकष्टं श्रितो महाकष्टश्रित इति । यदा त्वेतद्वाक्यं भवति—महत्कष्टं श्रित इति, तदा न भवितव्यम् । तदा च प्राप्नोति ॥

(प्रदीपः) **भवति यदेति ।** श्रितशब्दमनपेक्षमाणयोः परस्परापेक्षायां महत्कष्टयोः समासे कृते श्रितशब्देन समासः ।

(उद्द्योतः) [महाकष्टं श्रित इति । यदैवं वाक्यं तदा समासेन महाकष्टश्रित इति भवतीत्यर्थः ॥ **तदा न भवितव्यमिति ।** समासेनेति शेषः ॥]

(आक्षेपभाष्यम्)

तदा कस्मान्न भवति ? ॥

(प्रत्याक्षेपभाष्यम्)

कस्य कस्मान्न भवति । किं द्वयोः, आहोस्विद्बहूनाम् ? ॥

(प्रदीपः) **कस्य कस्मादिति ।** सामान्यनिर्देशः पदद्वयात्मकस्य पदत्रयात्मकस्य च समुदायस्य प्रदर्शनार्थः ॥

(उद्द्योतः) **सामान्येति ।** अन्यथैकपदस्य समासाभावेनैकवचननिर्देशोऽसंगतः स्यादिति भावः । तत्फलं दर्शयति—**पदद्वयात्मकस्येति** ॥

(आक्षेपाशयाविष्कारभाष्यम्)

बहूनां कस्मान्न भवति ? ॥

(प्रदीपः) **बहूनां कस्मान्न भवतीति ।** द्वयोरपि श्रितापेक्षया कर्मत्वे श्रितेन सामर्थ्यं द्वयोरप्यस्ति । कष्टस्यैव वा कर्मत्वे तद्द्वारेण महतोपि श्रितेन सामर्थ्यमस्तीति भावः ॥

(समाधानभाष्यम्)

सुप्सुपेति वर्तते ॥

(प्रदीपः) **सुप्सुपेति वर्तत इति**। संख्याया विवक्षितत्वादेकस्यैव सुबन्तस्यैकेनैव सुबन्तेन समासस्ततो बहूनां न भवतीत्यर्थः। यथा पशुना यजेतेत्यनेकस्य पशोरुपादानाभावस्तथेहापि॥

(उद्द्योतः) सुबित्यनेन सुबन्तसमुदायाग्रहणे हेतुमाह—**संख्याया इति**॥ अनियतसंख्यावच्छिन्नस्य संज्ञित्वेऽन्यवस्थापत्तेस्तद्विशेषाकाङ्क्षायामुपात्तसंख्यैव विवक्ष्यत इत्याशयेन दृष्टान्तमाह—**यथा पशुनेति**॥

(आक्षेपभाष्यम्)

ननु च भो आकृतौ शास्त्राणि प्रवर्तन्ते। तद्यथा—'प्रातिपदिकाद्' इति वर्तमानेऽन्यस्माच्चान्यस्माच्च प्रातिपदिकादुत्पत्तिर्भवति॥

(प्रदीपः) **ननु च भो इति**। यथा **ब्राह्मणो न हन्तव्य** इति सर्वस्य ब्राह्मणस्य हननप्रतिषेधस्तथेहापि बहूनां समासेन भाव्यमिति भावः॥

(उद्द्योतः) आकृतौ प्रवर्तमानस्य शास्त्रस्यापि तदाश्रयबहुव्यक्तिषु युगपत्प्रवृत्तिर्न दृष्टेत्याशङ्क्याह—**यथा ब्राह्मण इति**॥

(समाधानभाष्यम्)

सत्यमेवमेतत्। आकृतिस्तु प्रत्येकं परिसमाप्यते, न समुदाये। यावत्येतत् परिसमाप्यते प्रातिपदिकादिति, तावत उत्पत्त्या भवितव्यम्, प्रत्येकं चैतत्परिसमाप्यते,न समुदाये। एवमिहापि यावत्येतत्परिसमाप्यते सुप्सुपेति, तावतः समासेन भवितव्यम्। द्वयोश्चैतत्परिसमाप्यते, न बहुषु॥

(प्रदीपः) **आकृतिस्त्विति**। एकैकस्यां व्यक्तौ जातिनिमित्तप्रत्ययाभिधानसद्भावात्तत्र यथा प्रातिपदिकसमुदायस्याप्रातिपदिकत्वात्ततो विभक्तीनामनुत्पत्तिः। तथा सुबन्तसमुदायस्यासुबन्तत्वात् श्रितेन समासाभावः। प्रत्ययस्य सुबन्तसमुदायस्य च चिकीर्षितस्य प्रधानत्वाद् गुणत्वाच्च प्रातिपदिकस्यावयवयोश्च सुबन्तयोराधारगताया एकत्वसंख्याया विवक्षणात्। ब्राह्मणसमुदायस्य हनने तु शास्त्रार्थोतिक्रान्त एव भवतीति ब्राह्मणो न हन्तव्य इत्यादौ निषेधे संख्या न विवक्ष्यते॥

(उद्द्योतः) **एकैकस्यामिति**। तस्यामेवेत्यर्थः॥ **प्रत्ययाभिधानेति**। ज्ञानव्यवहारेत्यर्थः॥ **तथा सुबन्तसमुदायस्येति**। प्रत्ययग्रहणपरिभाषया तस्यासुबन्तत्वात्सुबन्तसमुदायस्य विवक्षितैकत्वकसुप्पदेन वक्तुमशक्यत्वादिति भावः॥ **चिकीर्षितस्य** विधेयत्वम्॥ संचिस्कीर्षितस्येत्यपाठः। भूषणाद्यर्थाभावात्सुटोऽप्राप्तेः समोऽनुपयोगाच्चेति बोध्यम्॥ **गुणत्वाच्च प्रातिपदिकस्येति**। प्रधानगता संख्या विवक्ष्यते इति ग्रन्थास्वार्थप्राधान्यमादाय बोध्याः॥ **आधारगताया इति**। जात्याधारद्रव्यगता संख्या विवक्ष्यत इत्यर्थः॥ नन्वेवं **ब्राह्मणो न हन्तव्य** इत्यत्रापि जात्याश्रयसंख्याया विवक्षा स्यात्तस्यापि गुणत्वादत आह—**ब्राह्मणसमुदायस्येति**। **शास्त्रार्थोऽतिक्रान्त एवेति**। न्यायेनैवं शास्त्रार्थे जाते कस्यातिक्रम इति चिन्त्यम्॥ परे तु **सुप्सुपेति वर्तत** इति भाष्यस्य **आकृतिस्तु प्रत्येकं समाप्यत** इति वक्ष्यमाण आशयः। इतरस्त्वेकत्वविवक्षयैकसुबन्तस्यैकसुबन्तेन समास इत्युक्तमिति मत्वा शङ्कते—**ननु च भो इति**॥ **आकृताविति**। प्रवृत्तिनिमित्ताश्रयसर्वव्यक्तावित्यर्थः। अन्यथा व्यक्तिवादेपि विनिगमनाविरहाद्रूपसामान्येन सर्वत्र कार्यप्रवृत्त्यैतदुक्तिरसंगता स्याद्। एवं नैकत्वविवक्षा कर्तुमशक्येति भावः॥ सिद्धान्ती स्वाशयं प्रकाशयति—**आकृतिस्त्विति**। शब्दप्रवृत्तिनिमित्तं त्वित्यर्थः। तदेवाह—**यावत्येतत्समाप्यते प्रातिपदिकादितीति**। एतत्पदप्रवृत्तिनिमित्तं प्रातिपदिकत्वादीत्यर्थः॥ **द्वयोश्चेति**। पदद्वयप्रवृत्तिनिमित्तं प्रत्येकं द्वयोरित्यर्थः। अयं भावः—यथा स्वाङ्गत्वजनपदत्वादेः प्रत्येकं समाप्त्या स्वाङ्गसमुदायजनपदसमुदाययोर्न स्वाङ्गजनपदग्रहणेन ग्रहणं तथा प्रकृतेपि। न च स्वाङ्गादित्यादावप्येकत्वविवक्षया तदर्थलाभस्तत्रलैकत्वस्य स्ववाचकप्रत्ययप्रकृत्यर्थस्वाङ्गवाचकशब्दान्वितत्वेपि स्वाङ्गानन्वितत्वेनैकस्वाङ्गवाचकादित्यर्थालाभात्। एको यः स्वाङ्गवाचकः शब्द इत्येतावत एव ततो लाभात्। एवं चोद्देश्यगता संख्याऽविवक्षितैवेति मीमांसकसिद्धान्तविरोधोपि न। किं च प्रातिपदिकसमुदायात्तद्धितशङ्कायां तत्समाधानपरे मतुप्सूत्रस्थे भाष्ये न कैयटोक्तप्रकारो न्याय्यस्तत्र ङ्याप्प्रातिपदिकादित्यस्य समस्तत्वेन समासे संख्याया अभानेनैकत्वस्याभानात्। श्रूयमाणविभक्त्यर्थैकत्वं तु समाहारान्वयीति बोध्यम्। न च तत्पर्याप्त्यधिकरणैरनेकैः समासादिवारणार्थं सा, **स्त्रीभ्यो ढगि**त्यादेः स्त्रीप्रत्ययान्तसमुदायादापत्तेस्तत्रापि सत्त्वात्। यथा च तत्र बहुवचनसत्त्वेप्येकैकस्त्रीप्रत्ययान्तादेव प्रत्ययस्तथान्यत्रापीत्याहुः॥

(आक्षेपभाष्यम्)

द्वयोस्तर्हि कस्मान्न भवति?॥

(समाधानभाष्यम्)

असामर्थ्यात्॥ कथमसामर्थ्यम्? । सापेक्षमसमर्थं भवतीति॥

(प्रदीपः) **सापेक्षमसमर्थं भवतीति**। न्यायोयम्। वृत्तौ सुपसर्जनपदेन प्रधानार्थाभिधायिना भाव्यम्। स्वविशेषणापेक्षायां च तस्य प्राधान्यमिति कथमेकस्यैकदा प्राधान्यमेकार्थीभावश्च स्यात्॥

(उद्द्योतः) **प्रधानार्थाभिधायिनेति**। प्रधानार्थविशेषणीभूतस्वार्थोपस्थापकेनेत्यर्थः। **प्राधान्यं, स्वार्थमात्रोपस्थापकत्वम्**॥

कथमेकार्थीभावश्चेति । कथमन्यविशेषणत्वेनैवोपस्थितिरित्यर्थः ॥ इतरविशेषणत्वेनोपस्थितस्य स्वविशेषणे आकाङ्क्षाभाव इति भावः ॥

(आक्षेपभाष्यम्)

यदि सापेक्षमसमर्थं भवतीत्युच्यते, राजपुरुषोऽभिरूपः 'राजपुरुषो दर्शनीयः' अत्र वृत्तिर्न प्राप्नोति ॥

(प्रदीपः) इतरस्तु वचनमेतदिति मत्वा चोदयति—**यदि सापेक्षमिति** ॥

(समाधानभाष्यम्)

नैष दोषः । प्रधानमत्र सापेक्षम् । भवति च प्रधानस्य सापेक्षस्यापि समासः ॥

(प्रदीपः) **भवति चेति** । प्राधान्यादेवानेकेनोपकारकेणोपकार्यत्वाविरोधात् । **सामान्याप्रयोग** इति लिङ्गदर्शनाच्च ॥

(उद्द्योतः) प्रधानस्य सापेक्षत्वेपि वृत्तावुपपत्तिमाह—**प्राधान्यादेवेति** ॥ नन्वेवं राजपुरुषो भार्यायाः इत्यपि स्यादत आह—**सामान्येत्यादि** । उपात्तविशेषणविजातीयविशेषणयोगः प्रधानस्य भवतीति ज्ञाप्यत इति भावः । यद्यपि समासे विशिष्ट एवान्वय इति प्रधानस्य न सापेक्षत्वं, तथापि दर्शनीयत्वाद्यन्वये पुरुषत्वमेव विशेष्यतावच्छेदकं न राजसंबन्धोपीत्याशयेन तथोक्तिरिति बोध्यम् ॥

(आक्षेपभाष्यम्)

यत्र तर्ह्यप्रधानं सापेक्षं भवति तत्र वृत्तिर्न प्राप्नोति—'देवदत्तस्य गुरुकुलम्' 'देवदत्तस्य गुरुपुत्रः' 'देवदत्तस्य दासभार्ये'ति ॥ [अत्र वृत्तिर्न प्राप्नोति ॥]

(समाधानभाष्यम्)

नैष दोषः । समुदायापेक्षात्र षष्ठी सर्वं गुरुकुलमपेक्षते ॥

(प्रदीपः) **समुदायापेक्षेति** । गुरुकुलादिना समुदायेन समुपजनिते व्यतिरेके देवदत्तस्येति षष्ठी । अवयवद्वारकश्च देवदत्तस्य समुदायेन संबन्ध इति सामर्थ्यादवयवमपि विशेषणं स्पृशति । तदुक्तम्—

समुदायेन संबन्धो येषां गुरुकुलादिना ।
संस्पृश्यावयवांस्ते तु युज्यन्ते तद्वता सह ॥ इति ॥

(उद्द्योतः) भाष्ये—**सर्वं गुरुकुलमिति** । गुरुसंबन्धविशिष्टं कुलं सर्वमपेक्ष्यते न तु तदवयवो गुरुरित्यर्थः । तदाह—**गुरुकुलादिनेति** ॥ नन्वेवं गुरौ देवदत्तसंबन्धित्वं न लभ्येतेत्यत आह—**सामर्थ्यादवयवमपीति** ॥ येषामर्थानां गुरुकुलादिरूपसमुदायेन संबन्धस्तेप्यर्था अवयवान्संस्पृश्य संबन्ध्य तद्वता युज्यन्त इति नाम पक्षेऽवयवानां तत्सम्बन्धालाभ इत्यर्थः ॥

(समाधानबाधकभाष्यम्)

यत्र तर्हि न समुदायापेक्षा षष्ठी तत्र ते वृत्तिर्न प्राप्नोति—'किमोदनः शालीनाम्' 'सक्त्वाढकमापणीयानाम्' 'कुतो भवान्पाटलिपुत्रक' इति । इह चापि 'देवदत्तस्य गुरुकुलं' 'देवदत्तस्य गुरुपुत्रो' 'देवदत्तस्य दासभार्ये'ति । यद्येषां समुदायापेक्षा षष्ठी स्यान्नैतन्नियोगतो गम्येत—देवदत्तस्य यो गुरुस्तस्य पुत्र इति । किं तर्हि ? । अन्यस्यापि गुरुपुत्रः, देवदत्तस्य किंचिदित्येषोर्थो गम्येत । यतस्तु खलु नियोगतो देवदत्तस्य यो गुरुस्तस्य यः पुत्र इत्येषोर्थो गम्यते, अतो मन्यामहे—नैषा समुदायापेक्षा षष्ठीति ॥ अन्यत्र खल्वपि समर्थग्रहणे सापेक्षस्यापि कार्यं भवति । क्वान्यत्र ? । "इसुसोः सामर्थ्ये" ब्राह्मणस्य सर्पिष्करोतीति । तस्मान्नैतच्छक्यं वक्तुं—सापेक्षमसमर्थं भवतीति ॥

(प्रदीपः) **किमोदन इति** । केषां शालीनां किं कलमानामथ रक्तानां शालीनामन्येषां वौदन इति प्रश्नः ॥ **सक्त्वाढकमिति** । आपणीयानां सक्तूनामाढकमित्यर्थः ॥ **कुतो भवानिति** । कस्मात् पाटलिपुत्राद्भवानागत इत्यर्थः । अनेकत्वात् पाटलिपुत्रस्य तदवयवानां वा प्रश्नः ॥ अत्र **रोपधेतोः प्राचाम**िति तद्धितवृत्तिर्न प्राप्नोति ॥ **इह चापीति** । समुदायसंबन्धे सति सामीप्यादेरपि प्रतिपत्तिप्रसङ्ग इत्यर्थः ॥ **नैषेति** । गुर्वपेक्षयात्र षष्ठी संबन्धिशब्दत्वाच्चात्र स्वार्थवदपेक्षाया वृत्तावप्यहानाद्भवत्येव वृत्तिः । उक्तञ्च—

संबन्धिशब्दः सापेक्षो नित्यं सर्वः प्रयुज्यते ।
वाक्यवत् सा व्यपेक्षा हि वृत्तावपि न हीयते इति।

अन्यत्रेति । ततो न वक्तव्यं सापेक्षमसमर्थं भवतीति । वाचनिके ह्यसामर्थ्ये यथा सर्पिः कालकमिति षत्वं न भवति **समानाधिकरणमसमर्थवद्**िति वचनात् । एवं ब्राह्मणस्य सर्पिष्करोतीत्यत्रापि न स्यात् ॥

(उद्द्योतः) किमः षष्ठ्यन्तापेक्षत्वमुपपादयति—**केषां शालीनामिति** । न तु शालीनां कीदृश ओदन इत्यर्थ इति भावः ॥ **कलमाः** । श्यामशालयः ॥ आपणीयानां मध्ये सक्त्वाढकमित्यर्थो नेत्याह—**आपणीयानां सक्तूनामिति** ॥ उक्तार्थे उपपत्तिमाह—**अनेकत्वादिति** ॥ एकत्वेपि तस्याह—**तदवयवानां वेति** ॥ **सामीप्यादेरपीति** । सामीप्यादिनिरूपितसंबन्धस्यापीत्यर्थः । अवयवद्वारकसंबन्धस्यैवात्र भानमित्यत्र नियामकाभावादिति भावः ॥ भाष्ये—**नैषा समुदायापेक्षेति** । एवं चाप्रधानस्यापि सापेक्षत्वे वृत्तिदर्शनात्सापेक्षमसमर्थमिति वक्तुमशक्यमिति भावः ॥ गमकत्वादत्र वृत्तिरिति वक्ष्यमाणाशयमाह—**संबन्धिशब्दत्वाच्चेति** । नित्यसापेक्षविषये आकाङ्क्षाया अशान्त्या प्रागुक्तन्यायविषयाभावा-

त्रासामर्थ्यमिति भावः ॥ **प्रयुज्यत इति** । समस्तत्वेनेत्यर्थः ॥ **स्वार्थवदिति** । स्वार्थ इव स्वार्थवत् । स्वार्थशब्दो भावप्रधानः । स्वार्थमात्रोपस्थापकवाक्यघटकतादशायामिव वृत्तावपीत्यर्थः ॥ किमोदन इत्यादयस्त्वसामर्थ्येपि भाष्यकारप्रयोगादेव साधव इति बोध्यम् ॥

सापेक्षमसमर्थमित्यस्य वाचनिकत्वे दूषणान्तरमाह—भाष्ये—**अन्यत्र खल्वपीति** । अन्यथा प्राक् कैयटोक्तन्यायस्यैकार्थीभावविषयत्वादिसुसोरित्यत्र व्यपेक्षारूपसामर्थ्यस्यैव ग्रहादसंगतिः स्पष्टैव ॥ तद्ध्वनयन्नाह—**वाचनिके हीति** ॥

(आक्षेपभाष्यम्)

वृत्तिस्तर्हि कस्मान्न भवति महत्कष्टं श्रित इति?॥

(प्रदीपः) स एवाह—**वृत्तिस्तर्हि कस्मादिति** ॥

(उद्द्योतः) **स एवेति** । मदीयं चोद्यं दुष्परिहरमित्याहेति भावः ॥

(११९० समाधानवार्तिकप्रथमखण्डम् ॥)

[॥ * ॥ सविशेषणानां वृत्तिर्न, वृत्तस्य वा विशेषणयोगो न ॥ * ॥]

(भाष्यम्) **सविशेषणानां वृत्तिर्न वृत्तस्य वा विशेषणं न प्रयुज्यते इति वक्तव्यम् ॥**

(प्रदीपः) **सविशेषणानामिति** । वृत्तिर्नेति वचनात् षत्वादि भवत्येव ॥ पूर्वोक्तानुसारेणायमपि न्याय एवोक्तः ॥

(आक्षेपभाष्यम्)

यदि सविशेषणानां वृत्तिर्न वृत्तस्य वा विशेषणं न प्रयुज्यत इत्युच्यते, 'देवदत्तस्य गुरुकुलम्' 'देवदत्तस्य गुरुपुत्रो' 'देवदत्तस्य दासभार्ये'त्यत्र वृत्तिर्न प्राप्नोति ॥

(समाधानवार्तिकद्वितीयखण्डम् ॥ १ ॥)

[॥ * ॥ अगुरुपुत्रादीनाम् ॥ * ॥]

(भाष्यम्) **अगुरुपुत्रादीनामिति वक्तव्यम् ॥**

(आक्षेपभाष्यम्)

तत्तर्हि वक्तव्यं सविशेषणानां वृत्तिर्न वृत्तस्य वा विशेषणं न प्रयुज्यते अगुरुपुत्रादीनामिति ॥

(समाधानभाष्यम्)

न वक्तव्यम् ॥ वृत्तिस्तर्हि कस्मान्न भवति? । अगमकत्वात् ॥ इह समानार्थेन वाक्येन भवितव्यं समासेन च । यश्चेहार्थो वाक्येन गम्यते 'महत्कष्टं श्रितः' इति, नासौ जातु चित्समासेन गम्यते 'महत्कष्टश्रितः' इति । एतस्माद्धेतोर्ब्रूमः—अगमकत्वादिति, न ब्रूमः—अपशब्दः स्यादिति ॥ यत्र च गमकत्वं भवति, भवति तत्र वृत्तिः । तद्यथा—'देवदत्तस्य गुरुकुलं' 'देवदत्तस्य गुरुपुत्रो' 'देवदत्तस्य दासभार्ये'ति ॥

(प्रदीपः) **न वक्तव्यमिति** । न्यायसिद्धत्वात् ॥ **इह समानार्थेनेति** । वाक्येनाभिधाने प्राप्ते समास आरभ्यमाणस्तत्समानार्थ एव न्याय्यः ॥ **महत्कष्टश्रित इति** । यः कष्टश्रितः स महत्कर्म करोतीत्यादि प्रतीयेत, क्रियाविशेषणं वा महत्त्वं प्रतीयेत, न तु कष्टविशेषणम् ॥ **न ब्रूम इति** । लोके प्रयुज्यमानस्य साधुत्वमसाधुत्वं च विचार्यते गोगाव्यादिशब्दवत् । महत्कष्टश्रित इत्ययं तु महत्कष्टं श्रित इत्येतद्वाक्यार्थे नैव प्रयुज्यते । प्रयुक्तानां चेदमन्वाख्यानम् । अतो नात्र समासो भविष्यतीत्यर्थः ॥

(उद्द्योतः) भाष्यकारो न्यायं दर्शयति—**अगमकत्वादि**त्यादिना ॥ **क्रियाविशेषणं वेति** । महद्यथा भवति तथा करोतीत्यर्थं इति भावः ॥ **न कष्टविशेषणमिति** । तस्य पदार्थैकदेशत्वादिति भावः । न चैवं कष्टं श्रित इत्यस्यापि विग्रहत्वं न स्यात् तत्र समाससमानाकाराया एवोपस्थितेः ॥ एतेन वृत्तिविग्रहयोः समानविषयताकत्वं सूचितम् ॥ विशेषणसमभिव्याहारे तु महदन्वयाय कष्टादेर्विशेषणत्वानाक्रान्तविशेष्यतयोपस्थितिरावश्यकीति तयोः समानार्थत्वभङ्गः ॥ इदमेव **पदार्थः पदार्थेनेति**व्युत्पत्तेर्मूलमिति दिक् ॥ भाष्ये—**एतस्माद्धेतोर्ब्रूम** इत्यादि ॥ अगमकत्वादित्येतस्माद्धेतोः **सापेक्षमसमर्थ**मित्यादि ब्रूमः । न तु संभावितापशब्दस्य साधुत्वनिवृत्तये तद्वाचनिकं ब्रूम इत्यर्थः ॥ तद्ध्वनयन्नाह—**यत्र गमक** इत्यादिना ॥ एतदेवाभिप्रेत्य व्याचष्ट—**लोके इत्यादिना** । अगमकत्वादेव तदर्थे शिष्टलोकैरप्रयुक्तत्वात्समासो न भवतीति भावः ॥ एवं च गमकत्वादेव **किमोदनः शालीना**मित्यादेरुपपत्तिः । कैयटाद्युक्तसंबन्धिशब्दत्वादियुक्त्या देवदत्तस्य गुरुकुलमित्यादेः साधुत्वेऽपपादितेपि **किमोदन** इत्यादेः साधुत्वं नोपपादितं स्यादतो भाष्योक्तमेव साधु ॥

(प्रत्याख्यानभाष्यम्)

यद्यगमकत्वं हेतुः, नार्थः समर्थग्रहणेन । इहापि 'भार्या राज्ञः पुरुषो देवदत्तस्य' इति योऽर्थो वाक्येन गम्यते, नासौ जातु चित्समासेन गम्यते 'भार्या राजपुरुषो देवदत्तस्य' इति । तस्मान्नार्थः समर्थग्रहणेन ॥

(प्रत्याख्यानबाधकभाष्यम्)

इदं तर्हि प्रयोजनम् । अयमस्त्यसमर्थसमासो नञ्समासो गमकः, तस्य साधुत्वं माभूत्—'अकिंचित्कुर्वाणम्' 'अमाषं हरमाणम्' 'अगाधादुत्सृष्टम्' इति ॥

(प्रदीपः) **नञ्समासो गमक इति** । गाव्यादिवदसाधुरपि गमकत्वाभिमतो लोके प्रयुज्यते तस्यासति समर्थग्रहणे

साधुत्वं प्राप्तं ततस्तन्निवृत्त्यर्थमेतदित्यर्थः ॥ किंचिदकुर्वाणं मापमहरमाणं गाधादनुत्सृष्टमित्येतेष्वर्थेष्वेते नञ्समासाः ॥

(उद्द्योतः) गमकश्चेत्तन्निवृत्तिरशक्येत्यत आह—**गमकत्वाभिमत इति** । तत्र हेतुर्लोके प्रयोगः । अतोऽसौ गमकत्वेनेष्ट इत्यर्थः । परं त्वसाधुरिति भावः ॥ असमर्थत्वमुपपादयति—**किंचिदकुर्वाणमिति** ॥

(प्रत्याख्यानसाधकभाष्यम्)

एतदपि नास्ति प्रयोजनम् । अवश्यं कस्यचिन्नञ्समासस्यासमर्थस्य गमकस्य साधुत्वं वक्तव्यम् । असूर्यंपश्यानि मुखानि 'अपुनर्गेयाः श्लोकाः' अश्राद्धभोजी ब्राह्मण इति ॥ "सुडनपुंसकस्य" इत्येतन्नियमार्थं भविष्यति—एतस्यैवासमर्थसमासस्य नञ्समासस्य गमकस्य साधुत्वं भवति नान्यस्येति । तस्मान्नार्थः समर्थग्रहणेन ॥

(प्रदीपः) **असूर्यंपश्यानीति** । सूर्यकर्मिकया दृशिक्रियया नञः संबन्धो न तु सूर्यस्थया सत्तयेत्यसामर्थ्यम् ॥ **अपुनर्गेया इति** । पुनर्न गेया इति गानेन नञः संबन्धो न तु पुनःशब्दार्थेन ॥ **अश्राद्धभोजीति** । भुजिना नञः संबन्धो न तु श्राद्धेन । श्राद्धे भोजननिषेधावगमात् ॥ **अनपुंसकस्येति** । प्रसज्यप्रतिषेधपक्षेऽयमसमर्थसमासः । असमर्थनञ्समासानां केषांचित् साधुत्वज्ञापनायानपुंसकस्येति प्रसज्यप्रतिषेध आश्रीयते । पर्युदासेपि ह्यत्र न क्षतिः । तदेवं समर्थग्रहणे क्रियमाणे विध्यर्थमेतेषां ग्रहणं कर्तव्यं तदेवाक्रियमाणे नियमार्थं भविष्यतीत्यर्थः ॥ **एतस्यैवेति** । अभेदमाश्रित्यैकवचनं कृतम् । एतेषां बहुत्वाद्बहुवचनप्रसङ्गः । असमर्थसमासेपि क्रियायामुभयोः सन्निपातादेकार्थीभावस्तद्द्वारकोऽस्त्येव ॥

(उद्द्योतः) **न सूर्यस्थया सत्तयेति** । सूर्यपदार्थघटकधात्वर्थेनेत्यर्थः । कर्मणि न प्रेरयतीत्यसूर्य इत्यर्थो नेति भावः ॥ सूर्यशब्दस्य रूढत्वेपि सूर्यभिन्नमिति तेनान्वयाभावादसामर्थ्यमित्यपि बोध्यम् ॥ **नियमार्थं भविष्यतीति** । एवं चाकिंचित् कुर्वाणमित्यादयः प्रयोगाः प्रागुक्ता असाधव इति भावः ॥ असूर्येत्यादीनां प्रागुक्तानां बहूनां साधुत्वस्येष्टत्वादेकवचनमनुपपन्नमत आह—**अभेदमिति** । **एतस्यैवेति**भाष्यस्य प्रागुक्तस्येत्यर्थ इति भावः ॥ **क्रियायामुभयोरिति** । इदं चिन्त्यम् । कृतः सर्वो मृत्तिकयेत्यादौ समासापत्तेः । असामर्थ्येपि ज्ञापकात्कचित्समास इत्येव भाष्याशयेनास्योपयोगाभावाच्च । प्रातिपदिकसंज्ञाप्यसूर्यललाटयोरित्यनपुंसकस्येति च ज्ञापकादिति भाष्याशयः ॥

(अथ सामर्थ्यलक्षणभेदनिरूपणाधिकरणम्)

(आक्षेपभाष्यम्)

अथ क्रियमाणेपि समर्थग्रहणे समर्थमित्युच्यते । किं समर्थं नाम ? ॥

(प्रदीपः) **अथ क्रियमाणेपीति** । अबुधबोधनार्थं करणेभ्युपगम्यमाने इत्यर्थः ॥ **किं समर्थं नामेति** । यद्यपि पूर्वमेकार्थीभावो वा सामर्थ्यं व्यपेक्षा वेत्याद्युक्तं तथाप्येतद्विचारस्थानं तस्य । एतत्सिद्धेन तु पूर्वं व्यवहारः कृतः ॥

(उद्द्योतः) **अबुधेति** । सर्वत्र गमकत्वागमकत्वे लक्षणैकचक्षुष्कैर्दुर्ज्ञेये इति भावः । कृतेपि क्वचित्परम्परोपदेशगम्यगमकत्वादिनैव सर्वप्रयोगनिर्वाह इति बोध्यम् ॥ **एतत्सिद्धेनेति** । अत्रत्यवार्त्तिककारीयसिद्धविचारमुपादाय पूर्वं भाष्यकृता व्यवहृतमिति भावः ॥

(११९१ समाधानवार्तिकम् ॥ २ ॥)

॥ * ॥ पृथगर्थानामेकार्थीभावः समर्थवचनम् ॥ * ॥

(व्याख्याभाष्यम्)

पृथगर्थानां पदानामेकार्थीभावः समर्थमित्युच्यते ॥

(प्रदीपः) **पृथगर्थानामिति** । एकार्थीभावं तावत् सामर्थ्यं दर्शयति ॥ परस्ताद्व्यपेक्षालक्षणं दर्शयिष्यति ॥ पृथगर्था येषां पदानां तानि पृथगर्थानि पदानि । वाक्ये हि राज्ञः पुरुष इत्यत्र राजशब्दो राजार्थमेवाचष्टे, पुरुषशब्दोपि पुरुषार्थमेव । वृत्तौ तु राजपुरुष इत्यत्र राजशब्दोपि पुरुषार्थमेवाचष्टे इति द्वयोरेकार्थीभावो भवति । अथ वान्य एवावयवार्थान्वितः समुदायार्थः प्रादुर्भवतीति तदपेक्षयैकार्थीभाव उच्यते पांसूदकवदेकभावापन्नत्वात् ॥ यद्यपि शब्दान्तरमेव वृत्तिः, अवयवा वर्णवदनर्थकाः । तथापि सादृश्यात् तस्याध्यवसायं पदानामाश्रित्य **पृथगर्थानामेकार्थीभाव** इत्युक्तम् ॥ **समर्थवचनमिति** । समर्थशब्दस्य वाच्य इत्यर्थः । कर्मणि ल्युट् ॥

(उद्द्योतः) **पृथगर्था इति** । अर्थेषु पृथक्त्वं भिन्नभिन्नोपस्थितिविषयत्वम् ॥ **आचष्टे** । उपस्थापयति ॥ **राजशब्दोपि पुरुषार्थमेवेति** । पुरुषार्थान्वितमेव स्वार्थमुपस्थापयतीत्यर्थः ॥ अजहत्स्वार्थायामप्याह—**अथ वेति** ॥ **अवयवार्थान्वित इति** । पूर्वपदरूपावयवार्थसदृशार्थान्वित इत्यर्थः । तदुक्तम**न्य एवेति** ॥ **समुदायार्थः** । समुदायशक्तिगम्यः । क्वचित्तु—**अवयवार्थानन्वित** इति पाठः । तदा स्पष्टमेवान्य एवेत्यस्य विवरणमिदम् ॥ द्वन्द्वबहुव्रीह्योरेकार्थीभावस्तु सूत्रोपक्रमे दर्शितः ॥ एकार्थत्वमविभागापन्नार्थत्वमपृथगुपस्थितिविषयार्थकत्वं तदाह—**पांसूदकवदिति** । यथा मिलितपांसूदकेऽन्यतराविषयकज्ञानविषयत्वं नान्यतरस्य, तथा प्रकृतेप्यन्यतमाविषयकोपस्थितिविषयत्वं नान्यतमस्येत्यर्थः । यथा पांसूदकमिलने पिण्डाख्यं द्रव्यान्तरमेवैकभावमापन्नं तयोस्तदवयवत्वव्यवहारश्च तद्वदत्रापीति भावः । एवं चापृथगुपस्थितिविषयत्वमेकार्थीभाव इति फलितम् । गौणमेकार्थत्वं समासघटकपदानां

बोधयितुं च्विनिर्देशः। पदानामसत्त्वाद्यथा तत्सत्ताव्यवहारो गौणस्तथा तेषामेकार्थत्वव्यवहारोपीति बोध्यं तदाह—यद्यपीति॥ साद्दश्यादिति। यद्यप्येतत्पक्षे वाक्यमप्यखण्डमेव तथापि रेखागवयस्थानीयेन शास्त्रनिष्पन्नेन सखण्डेन सादृश्यं बोध्यम्॥ एकार्थीभाव इत्यनेन समर्थवचनमित्यस्य सामानाधिकरण्यानुपपत्तेराह—कर्मणीति॥ बाहुलकादिति शेषः॥ सामान्ये च नपुंसकम्। तद्ध्वनितं भाष्ये—समर्थमित्युच्यते इति॥

(आक्षेपभाष्यम्)

क्व पुनः पृथगर्थानि, क्वैकार्थानि?॥

(प्रदीपः) **क्व पुनरिति।** पृथगर्थत्वमेकार्थत्वं च विरुद्धत्वादेकस्मिन्विषये न संभवतीति प्रश्नः॥

(समाधानभाष्यम्)

वाक्ये पृथगर्थानि 'राज्ञः पुरुषः' इति। समासे पुनरेकार्थानि 'राजपुरुषः' इति॥

(प्रदीपः) **राज्ञः पुरुष इति।** राज्ञ इत्यनेन पदेन राजार्थोऽनियतसंबन्ध्यपेक्षयोद्भूतसंबन्धो विशेषणभावमापन्नोऽभिधीयते। पुरुष इत्यनेन तु पुरुषार्थः स्वनिष्ठो विधीयमानत्वात् प्राधान्यमापन्नोभिधीयते। वृत्तौ भेदस्य निवर्तनात्तदधिष्ठानस्यापि संबन्धस्यान्तर्भावात् षष्ठी निवर्तते। सैव च स्वाभाविकी निवृत्तिः **सुपो धातुप्रातिपदिकयो**रिति शास्त्रेणान्वाख्यायते प्रत्ययलक्षणसिद्धये॥

(उद्योतः) वाक्यसमासयोर्विशिष्टपुरुषस्यैकस्यैवावगतेर्विशेषाभावमाशङ्क्याह—**राज्ञ इति। अनियतसंबन्ध्यपेक्षयेति** च्छेदः॥ उद्भूतसंबन्धशब्देन तद्वृत्तितया प्रतीयमानसंबन्धः॥ **विशेषणभावमापन्न इति।** विशेषणत्ववैशिष्ट्येनोपस्थित इत्यर्थः। स्वप्रकृत्यर्थगतविशेषणत्वस्यापि प्रथमातिरिक्तविभक्त्यर्थत्वादिति भावः॥ **अभिधीयते।** शक्त्योपस्थाप्यते॥ **स्वनिष्ठः।** प्रातिपदिकार्थमात्रनिष्ठः। प्रातिपदिकार्थमात्ररूप इति यावत्। न तु संबन्ध्यन्तरापेक्षयोद्भूतसंबन्ध इत्यर्थः॥ **विधीयमानत्वात्।** विधेयताख्यविषयतावत्त्वात्। प्रथमाया विधेयविभक्तित्वादिति भावः॥ तदेवाह—**प्राधान्यमिति॥ वृत्तौ भेदस्य** भिन्नोपस्थितिविषयत्वस्य। यथा घटघटत्वयोः घटशब्दजन्यसंबन्धाविषयकोपस्थितिविषयत्वं तथा वृत्तौ राजपुरुषयोरिति भावः॥ **संबन्धस्यान्तर्भावात्।** राजपुरुष इति समुदायेनैवोपस्थापनादित्यर्थः॥ **उक्तार्थानामप्रयोग** इति षष्ठ्या निवृत्तिरिति भावः॥

(आक्षेपभाष्यम्)

किमुच्यते—पृथगर्थानीति। यावता 'राज्ञः पुरुष आनीयताम्' इत्युक्ते राजपुरुष आनीयते। 'राजपुरुषः' इति च स एव?॥

(प्रदीपः) **किमुच्यत इति।** एवं हि वाक्ये पदानां पृथगर्थत्वं स्याद्यद्येक एव विशिष्टार्थो न प्रतीयेत। वृत्तौ च पुरुषमात्रप्रतीतौ स्यादेकार्थीभावः। यतस्तु वृत्तिवाक्ययोरेक एवार्थः प्रतीयते तदा सामर्थ्यभेदोपि नास्ति॥

(उद्योतः) उक्तविशेषस्य गम्यमानतयाऽविशेषोक्तिः कथमित्यत आह—**एवं हीति। पृथगर्थत्वं स्यादिति॥** समासापेक्षया परस्परापेक्षया च भिन्नार्थत्वं स्यादित्यर्थः॥ **न प्रतीयेतेति।** पदाभ्यामिति शेषः॥ **सामर्थ्यभेदोपीति।** व्यपेक्षैकार्थीभावरूप इत्यर्थः॥

(समाधानभाष्यम्)

नापि ब्रूमः—अन्यस्यानयनं भवतीति॥

(प्रदीपः) **नापि ब्रूम इति।** वाक्ये पृथगर्थत्वेपि पदानामाकाङ्क्षायोग्यतावशाद्विशेषणविशेष्यभावाद्विशिष्टार्थप्रतीतिः। वृत्तावपि विशिष्ट एवार्थो राजपुरुषशब्दाभ्यामभिधीयत इति कुतोऽन्यस्यानयनम्। न चैतावता वृत्तिवाक्ययोरेकार्थता। यथा ब्राह्मणानां शतं भोज्यतां शतं ब्राह्मणा भोज्यन्तामिति सत्यपि कार्यस्याभेदे शब्दार्थो भिद्यते तथेहापीत्यर्थः॥

(उद्योतः) भाष्ये—**नापि ब्रूम इति।** नैव ब्रूम इत्यर्थः॥ **वाक्ये पृथगर्थत्वेपीति।** पृथगुपस्थितिविषयत्वेपीत्यर्थः॥ **एकार्थता,** एकसामर्थ्यवत्ता॥

(एकार्थीभावफलनिरूपणाधिकरणम्)

(व्यपेक्षावादिन आक्षेपभाष्यम्)

कस्तर्ह्येकार्थीभावकृतो विशेषः?॥

(एकार्थीभाववादिनः समाधानभाष्यम्)

सुब्लोपो व्यवधानं यथेष्टमन्यतरेणाभिसंबन्धः स्वर इति॥

(सुब्लोपोदाहरणसमन्वयभाष्यम्)

सुब्लोपो भवति वाक्ये—राज्ञः पुरुष इति। समासे तु न भवति—राजपुरुष इति॥

(प्रदीपः) **सुब्लोप इति।** एकार्थीभावाभावकृतोपि विशेष एकार्थीभावकृत इत्युच्यते। सन्निधानासन्निधानाभ्यां क्रियाभिनिर्वृत्तौ पदार्थानां कारणत्वात्। यथा वर्षकृतं सुभिक्षं वर्षकृतं दुर्भिक्षमिति चोच्यते। तत्र राज्ञः पुरुष इति वाक्ये भेदाधिष्ठानस्य संबन्धस्य प्रत्याययिषितत्वाद्विना विभक्त्या तस्य प्रत्याययितुमशक्यत्वान्नास्ति सुब्लोपः। समासे कृते भेदनिवृत्तौ तदाश्रयस्य संबन्धस्योपरमात् स्वाभाविकी सुपो निवृत्तिः। सैव च शास्त्रेणानुज्ञायते। तदेवं सुपो भावाभावाभ्यामर्थस्य भावाभावावनुमानं वाक्यसमासयोः॥

(उद्योतः) एकार्थीभावकृतविशेषप्रश्ने सुब्लोप इत्यादिकथनमसंगतमत आह—**एकार्थीभावाभावेति।** यथा मशकनिवृत्तिकारणमपि धूमो मशककारणमित्युच्यते मशकार्थो धूम इति, तथा तदभावकारणकमपि तत्कारणकमित्युच्यते। तदुक्तं पातञ्जलभाष्ये—

"उत्पत्तिस्थित्यभिव्यक्तिविकारप्रत्ययाप्तयः।
वियोगान्यत्वधृतयः कारणं नवधा स्मृतम्"॥

उभयत्रापि राजसंबन्धवत्पुरुषप्रतीत्यविशेषे क्वचिद्विभक्त्यादिः क्वचिन्नेति विभागः कथमित्यत आह—**तत्रेति** । वाक्यीयन्यायेन विशेषणत्वमेव षष्ठीप्रवृत्तौ निमित्तं तत्रैव संबन्धस्योद्भूततया भानादिति भावः ॥ **भेदनिवृत्ताविति** । भिन्नोपस्थितिविषयत्वमत्र भेदः ॥ **संबन्धस्योपरमादिति** । प्रातिपदिकोक्ततया तदाकाङ्क्षोपरमादित्यर्थः ॥ **अर्थस्येति** । अर्थगतभिन्नोपस्थितिविषयत्वस्येत्यर्थः ॥

(व्यवधानोदाहरणसमन्वयभाष्यम्)

व्यवधानं भवति वाक्ये—राज्ञः ऋद्धस्य पुरुष इति । समासे तु न भवति—राजपुरुष इति ॥

(प्रदीपः) व्यवधानमपि सत्यर्थभेदे दृष्टं वाक्ये यथा भार्या राज्ञः पुरुषो देवदत्तस्येति । असति न दृष्टम् । देवदत्त इत्यत्र पदमध्ये पदान्तरस्य प्रक्षेप्तुमशक्यत्वात् ॥

(उद्द्योतः) ऋद्धस्येत्यस्य राजसमानाधिकरणत्वेनैकार्थ्याद्व्यवधायकत्वमिति मन्वानं प्रति स्पष्टमुदाहरणमाह—**भार्या राज्ञ इति** । भार्या देवदत्तस्येत्यस्य मध्ये राज्ञः पुरुष इत्यनेन व्यवधानमिति बोध्यम् ॥

(यथेष्टाभिसंबन्धोदाहरणसमन्वयभाष्यम्)

यथेष्टमन्यतरेणाभिसंबन्धो भवति वाक्ये—'राज्ञः पुरुषः' पुरुषो राज्ञ इति ॥ समासे न भवति—राजपुरुष इति ॥

(प्रदीपः) **यथेष्टमिति** । वाक्येऽनियतपौर्वापर्येण पदानां प्रयोगः । समासे तु नियतपौर्वापर्यः ॥ स चार्थभेदनिबन्धनः । यथा कर्क इति प्रयोक्तव्ये कंक इति न प्रयुज्यते ॥

(उद्द्योतः) ननु वाक्येपि राज्ञो विशेषणताया एव नियतत्वाद्यथेष्टमभिसंबन्ध इत्यनुपपन्नमत आह—**वाक्ये अनियतेति** । पौर्वापर्यलक्षणः शब्दगतोऽभिसंबन्धो भाष्याभिप्रेत इति भावः ॥

(स्वरोदाहरणसमन्वयभाष्यम्)

द्वौ स्वरौ भवतो वाक्ये—राज्ञः पुरुष इति । समासे पुनरेक एव—राजपुरुष इति ॥

(प्रदीपः) **द्वौ स्वराविति** । अर्थभेदे स्वरभेदो दृश्यते यथा देवदत्त गामभ्याजेति । तदभेदे न दृश्यते यथा— घट इति । अत्र राज्ञः पुरुष इति द्वे अपि पदे नित्स्वरेणाद्युदात्ते । राजपुरुष इति समासान्तोदात्तः ॥

(उद्द्योतः) समासासमासकृतः स्वरविशेषो नैकार्थीभावकृत इत्यत आह—**अर्थभेदे इति** ॥ **स्वरभेद इति** । स्वरशब्देनोदात्तः स्वरितो वाऽत्र विवक्षित इति बोध्यम् ॥ **द्वे अपीति** । राजन्शब्दः कनिनन्तः, पुरुषः कुषनन्त इति भावः ॥

(समाधानबाधकव्यपेक्षावादिभाष्यम्)

नैत एकार्थीभावकृता विशेषाः ॥ किं तर्हि ? । वाचनिकान्येतानि । आह हि भगवान्—"सुपो धातुप्रातिपदिकयोः" "उपसर्जनं पूर्वम्" समासस्यान्त उदात्तो भवतीति ॥

(प्रदीपः) **वाचनिकानीति** । वचनेनैवंभूतानामन्वाख्यानाद्व्यभिचाराच्चानुमानं सुब्लोपादिकमर्थाभेदस्येत्यर्थः । यथा पयः पयो जरयतीत्यत्र विनापि विभक्त्या कर्तृकर्मप्रतीतिर्भवति पचकप्रातिपदिकार्थदर्शने । तथा राजपुरुष इत्यत्र सत्येवार्थाभेदे राजपदमेव संबन्धमभिदध्यात् । अर्थाभेदे च सुब्लोपो दृष्टः । यथा वर्षासुजः गोपुचर इति ॥ तथा वृत्तावपि प्रयोगानियमो दृश्यते—अन्तादी आद्यन्तौ जातपुत्रः पुत्रजात इति ॥ वाक्ये चप्रयोगनियमो धवश्च खदिरश्चेति । नहि भवति च खदिरश्च धव इति ॥ ऐकस्वर्यं च दृश्यते वाक्ये—'तीक्ष्णेन परशुना. वृश्चाम्'ति । अर्थभेदे च स्वरभेदः —'कर्तवै, अन्वेतवै' इति **अन्तश्च तवै युगपत्" तवै चान्तश्च युगपदि"**त्यत्र स्वरः ॥

(उद्द्योतः) **सिद्धे शब्दार्थसंबन्ध** इत्युक्तेर्वाचनिकत्वं कथमत आह—**वचनेनेति** ॥ व्यभिचारमेव दर्शयति—**यथेति** ॥ ननु वाचकाभावे कथं तत्प्रतीतिरत आह—**पचकेति** । तात्पर्यग्राहकं तु प्रकरणादीति भावः ॥ इदमेव दर्शनं सिद्धान्तिन इति बोध्यम् ॥ **राजपदमेवेति** । शब्दशक्तिस्वभावादिति भावः ॥ एतेन विभक्त्यर्थस्य प्रातिपदिकार्थत्वं न दृष्टमित्यपास्तम् । शब्दाभावेऽर्थसद्भावं प्रदर्श्य शब्दसद्भावेप्यर्थाभावं दर्शयति—**अर्थाभेदे चेति** । अभिन्नोपस्थितिविषयत्वे चेत्यर्थः ॥ **वाक्ये चेति** । चादीनां निपातानां परप्रयोग एवेति भावः ॥ **तीक्ष्णेनेति** । पराङ्गवद्भावात्स्वरैक्यमत्रेत्यर्थः ॥ **अन्तश्च तवै इति** । आद्यम् असमासे, ऽन्त्यं समासे स्वरविधायकम् ॥

(एकार्थीभाववादिसमाधानान्तरभाष्यम्)

इमे तर्ह्येकार्थीभावकृता विशेषाः—संख्याविशेषो व्यक्ताभिधानमुपसर्जनविशेषणं चयोग इति ॥

(संख्याविशेषोदाहरणसमन्वयभाष्यम्)

संख्याविशेषो भवति वाक्ये—राज्ञः पुरुषः 'राज्ञोः पुरुषः' राज्ञां पुरुष इति । समासे न भवति—'राजपुरुषः' इति ॥

(प्रदीपः) **संख्याविशेष इति** । वाक्ये उपसर्जनपदानि विभक्त्यर्थाभिधायित्वात् संख्याविशेषयुक्तं स्वार्थं प्रतिपादयन्ति । समासे त्वन्तर्भूतस्वार्थं प्रधानार्थमभिदधतीत्यभेदैकत्वसंख्यां गमयन्ति । संख्याविशेषाणामविभागेनावस्थानम**भेदैकत्वसंख्या** ॥ [यथोक्तम्—]

"यथौषधिरसाः सर्वे मधुन्याहितशक्तयः ।
अविभागेन वर्तन्ते तां संख्यां तादृशीं विदुरिति॥

अथवा परित्यक्तविशेषसंख्यासामान्यमभेदैकत्वसंख्या। तदुक्तम्—

भेदानां वा परित्यागात्संख्यात्मा स तथाविधः।
व्यापाराज्जातिभागस्य भेदापोहेन वर्तते ॥
अगृहीतविशेषेण यथा रूपेण रूपवान्।
प्रख्यायते न शुक्लादिभेदरूपस्तु गम्यते" इति ॥

क्वचित्तु संख्याविशेषाभिव्यक्तिर्भवति । यथा द्विपुत्रः पञ्चपुत्र इत्यादौ प्रातिपदिकार्थ एव संख्याविशेषः॥ तावकीनो मामकीन इत्यत्रादेशाभिव्यङ्ग्यमेकत्वम् ॥ शौर्पिकमिति प्रातिपदिकेन विशिष्टस्यैव परिमाणस्योपादानादेकत्वावगमः । तथा मासजात इति विशिष्टकालावगमाय प्रयोगादेकत्वावगतिः ॥ एवमन्यत्रापि प्रकारान्तरेण संख्याभेदावसायो द्रष्टव्यः ॥

(उद्द्योतः) **विभक्त्यर्थेति** । वाक्ये उपसर्जनबोधकपदानां विभक्त्यन्तत्वेन तदर्थसंख्याविशेषयुक्तार्थबोधकत्वमित्यर्थः॥ **अन्तर्भूतेति** । विशेषणीभूतस्वार्थकमित्यर्थः ॥ **अभेदैकत्वेति** । विभक्त्यभावेन संख्याविशेषाणां तत्तद्रूपेणाप्रतीतेः संख्यात्वेन सर्वसंख्यानां भानं मधुनि सर्वरसानां रसत्वेन भानवदिति भावः । तदाह—**यथौषधीति** ॥ **अथ वेति** । अत्र पक्षे संख्यात्वेन सामान्यं भासते, न तु विशेषा इति पूर्वस्माद्विशेषः ॥ संख्यावद्व्राजसंबन्धीति पक्षद्वयेपि बोधः । अत एव भाष्ये **संख्याविशेष** इति विशेषपदोपादानम् । मधुनि सर्वरससत्ताजन्यस्य तत्तद्रोगादिनिवृत्तिरूपस्य फलस्यानुभवात्तत्सत्ताकल्पनेप्यत्र सर्वसंख्याविशेषकल्पने मानाभाव इति तद्भावः ॥ **भेदानां** विशेषाणाम् ॥ **संख्यात्मा** संख्यासामान्यम् ॥ **तथाविधः** । अभेदैकत्वसंख्यापदवाच्यः ॥ निर्विशेषसामान्याभावादिदं कथमत आह—**व्यापारादिति** । संख्यात्वेनैव तत्प्रतीतेर्विशेषरूपाणां तत्तद्रूपेणाप्रतीतेश्च भेदापोह इति भावः ॥ तदेव समर्थयति—**अगृहीतेति** ॥ **शुक्लादिरूपभेदस्त्विति** । शुक्लादिरूपविशेष इत्यर्थः । **भेदरूप** इति पाठे शुक्लादिविशेषरूपोर्थस्त्वित्यर्थः ॥ तत्र रूपत्वेन रूपप्रतीतिः सद्वस्तुविषयाऽत्र तु संख्यात्वेन प्रतीतिरसद्वस्तुविषया विकल्पात्मिकेति विशेषः ॥

(संख्याविशेषानवगतौ कारणान्तरभाष्यम्)

अस्ति कारणं येनैतदेवं भवति ॥ किं कारणम्?। योऽसौ विशेषवाची शब्दस्तदसांनिध्यात्। अङ्ग हि भवांस्तमुच्चारयतु गंस्यते स विशेषः ॥

(प्रदीपः) **तदसान्निध्यादिति** । लुका विभक्तेर्निवर्तितत्वादित्यर्थः ॥

(उद्द्योतः) नन्वेकार्थीभावकृतसंख्याविशेषाभावेनैव तदसांनिध्यमिति चेन्नेत्याह—**लुकेति** । लुक्शास्त्रपर्यालोचनयार्थसत्त्वमनुमीयत इति भावः ॥

(कारणान्तरनिराकरणभाष्यम्)

ननु च नैतेनैवं भवितव्यम् । नहि शब्दकृतेन नामार्थेन भवितव्यम् । अर्थकृतेन नाम शब्देन भवितव्यम् ॥

(प्रदीपः) **ननु चेति** । नहि विद्यमानेर्थे लुकमाचार्यो न्वाचष्टे, अपि त्वर्थस्याभावात् स्वत एव या शब्दस्य निवृत्तिः सैवानुगम्यत इत्यर्थः ॥ **अर्थकृतेनेति** । प्रत्याययिषितार्थप्रतिपादनाय शब्दप्रयोगात् ॥

(उद्द्योतः) ननु लुक्शास्त्रपर्यालोचनयाऽर्थसत्त्वमेवेत्यत आह—**नहीति** ॥ **अनुगम्यते इति** । बोध्यत इत्यर्थः । प्रत्ययलक्षणसिद्धय इति शेषः ॥

(भाष्यम्) **तदेतदेवं दृश्यताम्—अर्थरूपमेवंजातीयं येनात्र विशेषो न गम्यत इति । अवश्यं चैतदेवं विज्ञेयम् । यो हि मन्यते—'योसौ विशेषवाची शब्दस्तदसांनिध्यादत्र विशेषो न गम्यते' इति इह तस्य विशेषो गम्येत—अप्सुचरो गोपुचरो वर्षासुज इति ॥**

(प्रदीपः) **अर्थरूपमिति** । अर्थस्वभावः ॥ एतदुक्तं भवति—संख्याविशेषादियुक्तवस्तुप्रतिपादनेच्छायां वाक्यं प्रयुज्यते, अन्यदा तु वृत्तिः॥ **गोपुचर इति** । गोपुचरः कुक्कुट उच्यते । एकस्यां गवि द्वयोर्बहुषु वा यश्चरति स सर्वोसावविशेषेणोच्यते ॥ जातौ चेदं बहुवचनमिति व्यक्तिगतसंख्याभेदानवगमः । यदि तु व्यक्तिगतं बहुत्वं प्रतीयेत ततस्तदाश्रयमेव बहुवचनं क्रियेत । यदा तु सत्यपि बहुवचने व्यक्तिबहुत्वं न प्रतीयते तदा जात्याश्रयं बहुवचनमभ्युपगम्यते ॥ **वर्षासुज इति** । इन्द्रगोपः । अत्राप्येकस्मिन्नप्यृतौ अवयवबहुत्वापेक्षो बहुवचनान्तो वर्षाशब्दो वर्तते । नत्वत्र ऋतुबहुत्वं प्रतीयत इत्यत्राप्यभेदैकत्वमुपजायते । **तत्पुरुषे कृति बहुलमित्यत्रालुक्** ॥ लिङ्गविशेषस्यापि क्वचिद्वृत्तावुपादानं कुमारीपुत्र इति । क्वचित्त्यागः—कुक्कुटाण्डं मृगमांसमिति ॥ वाक्येपि जात्यन्तरनिवृत्तिपरे लिङ्गविशेषाविवक्षा दृश्यते छागस्य मांसमिति ॥

(उद्द्योतः) ननु जातौ बहुवचने कथं व्यक्तिगतसंख्याविशेषप्रतीत्यापादनमत आह—**यदि त्विति** । सत्यपि प्रत्यये तदनवगतेर्जातौ तदाश्रीयते इति भावः ॥ **जात्याख्यायामितिसूत्रप्रत्याख्यानादवयवबहुत्वारोपेण बहुवचनमित्यत्रापि वक्तुं युक्तम्** ॥ **अत्राप्यभेदैकत्वमिति** । अवयविगताभेदैकत्वमित्यर्थः । एवं हि दारा इत्यादावप्यवयविन्यभेदैकत्वं स्यादिति तस्य वृत्तिकृतविशेषत्वभङ्ग इति चिन्त्यम् ॥ संख्याविशेषवल्लिङ्गविशेषोपि कुतो नोक्तस्तत्राह—**लिङ्गविशेषस्यापीति** ॥ परे तु **संख्याविशेष** इत्यस्याप्रातिपदिकार्थसंख्याविशेष इत्यर्थः । तेन द्विपुत्रादौ न दोषः ॥

मासजातादौ शब्दात्संख्याऽप्रतीतिरेव ॥ मासत्वेन त्वेकमासस्यैव बोधः, अनेकमासजाते द्विमासजात इत्यादिदर्शनात् ॥ शब्दशक्तिस्वभावात्र कदापि तेनानेकमासस्य मासत्वेन बोधः ॥ त्वत्पुत्रो युष्मत्पुत्र इत्यादावपि तत्तच्चेतनपुत्र इत्येव बोधः । आदेशतदभावौ तु तत्त्वेन वस्तुत एकबोधतदभावाभ्याम् ॥ यथा घटानित्यादितो बहुत्वेनैव कदाचित्त्रयाणां कदाचिच्चतुरादीनां भानं, न तु कदाचिदपि त्रित्वचतुष्ट्वादिना तथा वृत्तौ राजत्वादिनैवैकानेकव्यक्तिभानं तात्पर्यवशाद् न त्वेकत्वद्वित्वादिना । एकवचनत्वादिकं वस्तुत एकत्वादिविशिष्टव्यक्तिबोधकत्वं न त्वेकत्वद्वित्वादिनेत्येतावत्पर्यन्तमाग्रहः ॥ एवमन्यत्रापि बोध्यम् ॥ दन्तोष्ठस्य दन्ताः स्निग्धतरा इत्यादाववयवसंख्याया अभानाद्दन्तत्वेनोष्ठत्वेन दन्तौष्ठलक्षणार्थद्वयप्रतीतिस्तत्रैव, अनेकव्यक्तिसत्त्वेपि तासां शब्दतोऽभानात् । अत एव भाष्यकृतोपसर्जनविशेषणरूपविशेषस्य देवदत्तस्य गुरुकुलमित्यादावव्यापकत्ववदस्य मासजातादावव्यापकत्वं नोक्तम् । अभेदैकत्वसंख्या भासत इति तु भाष्ये न क्वापि दृश्यत इत्याहुः ॥

(व्यक्ताभिधानोदाहरणसमन्वयभाष्यम्)

व्यक्ताभिधानं भवति वाक्ये—'ब्राह्मणस्य कम्बलस्तिष्ठति' इति। समासे पुनरव्यक्ताभिधानं 'ब्राह्मणकम्बलस्तिष्ठति' इति, संदेहो भवति–सम्बुद्धिर्वा स्यात्, षष्ठीसमासो वेति ॥

(प्रदीपः) **ब्राह्मणकम्बल इति** । यद्यप्यत्र स्वरान्निर्णयस्तथापि शब्दस्वरूपमात्रान्निश्चयाभाव इत्येवंपरमेतत् । यत्रापि नास्ति स्वरभेदः सम्बुद्धिषष्ठीसमासयोः 'तिष्ठति ब्राह्मणकम्बलः' इत्यादौः, तत्रापि प्रकरणादिवशादवश्यं निश्चयेन भाव्यम् । कम्बलशब्दो घृतादित्वान्निपातनाद्वान्तोदात्तः । एकार्थीभावे सति भेदनिबन्धनसंबन्धाभिधायिविभक्तिनिवर्तनात्तत्कृतो विशेषोऽव्यक्ताभिधानमुच्यते ॥

(उद्द्योतः) **नास्ति स्वरभेद इति । आमन्त्रितस्य** चेति पदात्परस्य निघातविधानादित्यर्थः ॥ ननु नियमेन सन्देहस्यैव जनने दुष्ट एव प्रयोगः स्यादत आह—**तत्र प्रकरणादीति** ॥ **निपातनाद्वेति** । **कम्बलाच्च संज्ञायामित्यादावित्यर्थः** ॥

(विशेषबाधकभाष्यम्)

एषोप्यविशेषः। भवति हि किंचिद्वाक्येऽव्यक्तम्, तच्च समासे व्यक्तम् । वाक्ये तावदव्यक्तम्—'अर्धं पशोर्देवदत्तस्य' इति, संदेहो भवति—पशुगुणस्य वा देवदत्तस्यार्धम्, अथ वा योसौ संज्ञीभूतः पशुर्नाम तस्य यदर्धमिति । तच्च समासे व्यक्तं भवति—अर्धपशुर्देवदत्तस्येति ॥

(प्रदीपः) **एषोपीति** । व्यभिचारात् । अपिशब्दः सुबलोपाद्यपेक्षया समुच्चयार्थः ॥

(उद्द्योतः) संख्याविशेषरूपस्य विशेषस्य सिद्धत्वादेषोपीत्यपिशब्दोऽयुक्त इत्यत आह—**अपिशब्द इति** ॥

(उपसर्जनविशेषणरूपविशेषोदाहरणभाष्यम्)

उपसर्जनविशेषणं भवति वाक्ये—ऋद्धस्य राज्ञः पुरुष इति । समासे न भवति—राजपुरुष इति ॥

(प्रदीपः) **ऋद्धस्येति** । राजा स्वार्थादप्रच्युतः पदान्तरार्थमप्रतिपन्नो वाक्ये योग्यत्वाद्विशेषणसंबन्धमनुभवति । वृत्तौ तूपसर्जनीभूतस्वार्थमर्थान्तरं प्रत्याययतीति अयोग्यत्वाद्विशेषणेन न संबध्यते ॥

(उद्द्योतः) पदान्तरार्थमप्रतिपन्नः । पदान्तरार्थान्वयित्वेनैवोपस्थितविषयः ॥ **अर्थान्तरं प्रत्याययतीति** । विशिष्टोपस्थितावस्यापि सहायत्वादिति भावः ॥ **अयोग्यत्वादिति** । पदार्थैकदेशत्वेनायोग्यत्वम् ॥

(बाधकभाष्यम्)

एषोप्यविशेषः। समासेप्युपसर्जनविशेषणं भवति । तद्यथा—देवदत्तस्य गुरुकुलं देवदत्तस्य गुरुपुत्रो देवदत्तस्य दासभार्येति ॥

(प्रदीपः) **एषोपीति** । अव्यापित्वात् ॥

(चयोगरूपविशेषोदाहरणसमन्वयभाष्यम्)

चयोगो भवति वाक्ये स्वचयोगः स्वामिचयोगश्चेति ॥ स्वचयोगः—राज्ञो गौश्चाश्वश्च पुरुषश्चेति । समासे न भवति—राज्ञो गवाश्वपुरुषा इति ॥ स्वामिचयोगः देवदत्तस्य च यज्ञदत्तस्य च विष्णुमित्रस्य च गौरिति । समासे न भवति—देवदत्तयज्ञदत्तविष्णुमित्राणां गौरिति ॥

(प्रदीपः) **चयोग इति** । वाक्ये पदार्थानां भिन्नत्वाद्भेदनिबन्धनसमुच्चयद्योतनाय चशब्दः प्रयुज्यते । वृत्तौ तु समूहलक्षणैकार्थप्रादुर्भावाद्भेदस्य निवर्तनाद्द्योत्यार्थाभावाद्द्योतकस्यापि चशब्दस्य निवृत्तिः ॥

(उद्द्योतः) **भिन्नत्वादिति** । भिन्नोपस्थितिविषयत्वादित्यर्थः ॥ **भेदनिबन्धनसमुच्चयेति** । घटपदजैकोपस्थितिविषययोर्घटघटयोः समुच्चयाप्रतीतेरिति भावः ॥ **भेदस्य निवर्त्तनादिति** । पृथगुपस्थितिनिवृत्तेरित्यर्थः ॥ **द्योत्यार्थाभावादिति** । समुच्चयाभावादित्यर्थः ॥

(आक्षेपभाष्यम्)

अथैतस्मिन्नेकार्थीभावकृते विशेषे किं स्वाभाविकं शब्दैरर्थानामभिधानम्, आहोस्विद्वाचनिकम् ? ॥

(प्रदीपः) **अथैतस्मिन्निति** । अयं भावः—यदि वाचनिकमर्थाभिधानं तदाऽसत्यप्येकार्थीभावे चार्थे द्वन्द्वविधानाद् द्वन्द्वेनैव चार्थस्योक्तत्वाच्चस्याप्रयोगोऽन्यथासिद्धत्वाभावादनुमानमेकार्थीभावस्य । स्वाभाविके तु चार्थे इत्यादिनिर्देशोऽनर्थकः ॥

(उद्द्योतः) पूर्वग्रन्थेन संगतिं वदन् अभिप्रायमाह—**अयं भाव इति** । यद्यपि चार्थे द्वन्द्वसंज्ञकसमुदायस्य शक्त्यैकार्थी-

भावः सिद्धस्तथाप्यवयवैः समुदायेन च पृथगुपस्थितानामन्वय इत्यपि संभाव्येत। तथा सति विशेषणाद्यन्वयोऽपि संभाव्येतेति भावः ॥

(समाधानभाष्यम्)

स्वाभाविकमित्याह ॥ कुत एतत्? ॥ अर्थानादेशनात् । न ह्यर्था आदिश्यन्ते ।

(प्रदीपः) अर्थानादेशनादिति । अचतुरविचतुरेत्यादाविति भावः ॥

(आक्षेपभाष्यम्)

कथं पुनरर्थानादिशन्नेवं ब्रूयात्–'नार्था आदिश्यन्ते' इति । यदाह भगवान्–"अनेकमन्यपदार्थे" "चार्थे द्वन्द्वः" अपत्ये, रक्ते, निर्वृत्ते, इति ॥

(प्रदीपः) आदिशन्निति । प्रवृत्ताविरामलक्षणं वर्तमानत्वं शास्त्रप्रबन्धानुपरमाद्दर्शयति । वाक्यभेदेन चार्थादेशनं मन्यते—'सुबन्तमनेकमन्यपदार्थे वर्तते, तच्च बहुव्रीहिसंज्ञम्' इति ॥ एवमन्यत्रापि वाक्यभेदो दर्शनीयः ॥

(उद्द्योतः) सकृदादेशनस्य भूतत्वाद्वर्तमानप्रयोगोऽसंगत इत्यत आह—प्रवृत्तेति । प्रबन्धो, धारा ॥ अर्थादेशनपरत्वे संज्ञापरत्वं न स्यादत आह—वाक्येति ॥

(समाधानभाष्यम्)

नैतान्यर्थादेशनानि । स्वभावत एतेषां शब्दानामेतेष्वर्थेष्वभिनिविष्टानां निमित्तत्वेनान्वाख्यानं क्रियते । तद्यथा—'कूपे हस्तदक्षिणः पन्थाः, अभ्रे चन्द्रमसं पश्य' इति स्वभावतस्तस्य तत्रस्थस्य पथश्चन्द्रमसश्च निमित्तत्वेनान्वाख्यानं क्रियते । एवमिहापि चार्थे यः स द्वन्द्वः, अन्यपदार्थे यः स बहुव्रीहिरिति ॥

(प्रदीपः) यदा तु लोकप्रसिद्धार्थानुवादेन बहुव्रीहिसंज्ञा विधीयते यदन्यपदार्थेऽनेकं वर्तते तद्बहुव्रीहिसंज्ञमिति, तदा नार्थादेशनं नापि वाक्यभेदः ॥ **अर्थेष्वभिनिविष्टानामिति** । अभिनिविशश्चेत्यत्र परिक्रयण इत्यतोऽन्यतरस्यांग्रहणानुवर्तनाद्विकल्पेन कर्मसंज्ञाविधानात् सप्तमी कृता । एतदेव च भाष्यकारवचनं लिङ्गं तद्विकल्पस्य ॥ **कूप इति** । कूपो लक्षणत्वेनोपादीयते हस्तदक्षिणमार्गग्रहणस्य । **अभ्र** इत्यत्राप्यभ्रं चन्द्रमसो लक्षणत्वेन निर्दिश्यते ॥

(उद्द्योतः) सिद्धान्ताभिप्रायमाह—**यदा त्विति ॥ विकल्पेन कर्मसंज्ञेति** । अतिप्रसक्तस्त्वनभिधानाद्वारणीयः ॥ भाष्ये—**अन्वाख्यानं क्रियते इति** । समासप्रत्ययादिसंज्ञां प्रतीति शेषः ॥ **चन्द्रमसश्चेति** । ग्रहणे दर्शने च कूपाभ्रयोरिति शेषः । तदाह—**कूपो लक्षणत्वेनेति** । निमित्तशब्दो ज्ञापकसाधारण इति भावः ॥

(आक्षेपभाष्यम्)

किं पुनः कारणमर्था नादिश्यन्ते? ॥

(प्रदीपः) **किं पुनरिति** । प्रकृतिप्रत्ययोपदेशवद्भवतु वाक्यभेदेनार्थादेशनमिति भावः ॥

(उद्द्योतः) वाक्यभेदरूपकारणस्य सत्त्वात् **किं पुनः कारणमित्यनुपपन्नमत** आह—**प्रकृतीति** । यथा ऋतेरीयङित्यादौ ॥

(समाधानभाष्यम्)

तत्र लघ्वर्थम् । लघ्वर्थं ह्यर्था नादिश्यन्ते । अवश्यं ह्यनेनार्थानादिशता केन चिच्छब्देन अर्थनिर्देशः कर्तव्यः स्यात् । तस्य च तावत्केन कृतः येनासौ क्रियते । अथ तस्य केनचित्कृतः, तस्य [केन कृतः, तस्य] केन कृत इत्यनवस्था च स्यात् ॥ असंभवः खल्वप्यर्थादेशनस्य । को हि नाम समर्थो धातुप्रातिपदिकप्रत्ययनिपातानामर्थानादेष्टुम् ॥

(प्रदीपः) **लघ्वर्थमिति** । लघुशब्दो लाघवे वर्तते । लाघवार्थमर्था नादिश्यन्ते । अन्यथा गौरवमनवस्था च प्राप्नोति । तथा हि—यदि 'चार्थे वर्तते अनेकं तच्च द्वन्द्वसंज्ञम्' इति वाक्यभेदेनार्थादेशनं क्रियते, तदैवं प्रष्टव्यं स्यात् 'कः पुनश्चार्थ' इति, तत्राचार्येण वक्तव्यं स्यात् 'समाहार इतरेतरयोगश्च' । ततः 'कः समाहारः, क इतरेतरयोग' इति प्रश्नप्रतिवचनयोरनवस्था गौरवं चानुपज्यते ॥ **असंभव इति** । असामर्थ्यात् ॥ दोषबाहुल्यप्रतिपादनाय चार्थादेशनस्य गौरवानवस्थासंभवाः परस्परान्तर्भावेऽपि पृथगुपन्यस्ताः ॥ **कोहीति** । अनेकार्थत्वादिति भावः । तत्र धातूनामनेकार्थत्वं कुर्दखुर्दगुर्दगुदक्रीडायामेवेति नियमार्थादेवकाराद्विज्ञायते । प्रातिपदिकानामपि यथेच्छं विनियोगदर्शनात् ॥ शक्तिनियमे तु पुरुषस्य व्यापारः ॥ प्रत्ययानां तु **कृत्यल्युटो बहुलं शेष** इति च लक्षणारम्भात् । निपातानामनेकार्थत्वं नानाविधस्यार्थस्य प्रयोगे द्योतनात् ॥

(उद्द्योतः) लघ्वर्थमित्युक्त्याऽर्थादेशने गौरवमित्युक्तं, दोषान्तरमनवस्थामप्याह—**अवश्यं ह्यनेनेत्यादिना ॥ तस्य च तावत्केन कृत इति** । यथा चार्थ इत्यत्र चस्यायमर्थ इति केन शब्देनोक्तं यत्करणकचार्थज्ञानेनासौ व्यवहारः क्रियते, येन शब्देन च तदुक्तं तत्रापि चायमेव पर्यनुयोग इत्यर्थः ॥ **अनुपज्यते इति** । भाष्येऽनवस्था च स्यादिति पाठे चेन गौरवमनुपज्यत इत्यर्थः ॥ असंभवे हेतुरसामर्थ्यादिति । आदेष्टुरिति शेषः ॥ गौरवानवस्थासंभवानां परस्परान्तर्भावेण पृथगुपन्यासोऽसंगत इत्यत आह—**दोषबाहुल्येति ॥ एवकारादिति । अनेकार्था अपि धातव** इति तत्र तत्र भाष्योक्तेरित्यपि बोध्यम् ॥ **यथेष्टमिति** । गङ्गादिशब्दानां तीरादावपि प्रयोगादिति भावः ॥ नन्वेवं कोशासंगतिरत आह—**शक्तिनियमे त्विति** । शक्तिबोधने त्वित्यर्थः ॥

(आक्षेपभाष्यम्)

न चैतन्मन्तव्यं प्रत्ययार्थे निर्दिष्टे प्रकृत्यर्थोऽनि-

र्दिष्ट इति । भवति हि गुणाभिधाने गुणिनः संप्रत्ययः । तद्यथा—शुक्लः कृष्ण इति ॥

(प्रदीपः) न चैतन्मन्तव्यमिति । कस्यचिदेवार्थो निर्दिश्यते अन्यस्य तु संबन्धात् प्रतीतिर्भवतीति भावः ॥ भवतीति । एकत्वादिषु गुणेषु स्वादयो विधीयन्ते गुणैश्च गुणिन आक्षेपो भवति निराधारस्य गुणस्यासंभवात् ॥ तद्यथा शुक्ल इति । गुणमात्राभिधाने गुणिन आक्षेप इत्यर्थः । तथाऽपत्ये प्रत्यये विधीयमाने सामर्थ्यादपत्यवतः प्रकृत्यर्थस्याक्षेपान्निर्देशः सिद्ध्यति ॥

(उद्द्योतः) प्रकृतीनामर्थनिर्देशो नावश्यक इत्याक्षिपति-भाष्ये—न चैतदिति ॥ प्रत्ययार्थे निर्दिष्टे इति । प्रत्ययार्थनिर्देशे प्रकृतीनामर्थस्य संबन्धादेव प्रतीतिसंभवेन प्रकृतीनामर्थनिर्देशो न कार्य इति भावः ॥ प्रत्ययार्थे निर्दिष्टे प्रकृत्यर्थस्य निर्देशो न कृत इत्येतन्न मन्तव्यमित्यक्षरार्थः ॥ एवं च प्रकृत्यर्थनिर्देशो नावश्यक इति भावः ॥ तदाह—कस्यचिदेवेति । भाष्ये पूर्वपक्षी स्वोक्तं साधयति—भवति हीति ॥ द्व्येकयोरित्यादाविति शेषः ॥ स एव गुणेन गुणिन आक्षेपे दृष्टान्तमाह—तद्यथेति ॥ गुणमात्रेति । सामर्थ्यादेव गुणिप्रतीतौ स्वाभाविकी मतुपो निवृत्तिरिव गुणवचनेभ्यो मतुपो लुगित्यनेनान्वाख्यायत इति भावः । इदमपि संबन्धिनः पदेनानुपादाने इति बोध्यम् ॥ गुणशब्दः संबन्धिशब्दोपलक्षणमित्याह—एवमपत्ये इति । तथाऽपत्ये इति पाठान्तरम् ॥

(समाधानभाष्यम्)

विषम उपन्यासः । सामान्यशब्दा एत एवं स्युः । सामान्यशब्दाश्च नान्तरेण प्रकरणं विशेषं वा विशेषेष्ववतिष्ठन्ते । यतस्तु खलु नियोगतो वृक्ष इत्युक्ते स्वभावतः कस्मिंश्चिदेव विशेषे वृक्षशब्दो वर्तते, अतो मन्यामहे—नेमे सामान्यशब्दा इति । न चेत्सामान्यशब्दाः, प्रकृतिः प्रकृत्यर्थे वर्तते । प्रत्ययः प्रत्ययार्थे वर्तते ॥

(प्रदीपः) विषम इति । यथा शुक्लः कृष्ण इति गुणेन गुणिमात्रस्याक्षेपो, न गुणिविशेषस्य । एवं वृक्षः प्लक्ष इत्यत्राप्येकत्वाधारो द्रव्यमात्रं प्रतीयेत । यदि लोकादर्थावधारणं नाश्रीयेत, नापि शास्त्रेण प्रतिप्रकृति निर्दिश्येतार्थः । तदा वृक्षादयो द्रव्यमात्राभिधायिनः स्युरिति प्रकरणाद्यभावे विशेषसंप्रत्ययो न स्यात् । भवति च । तस्माद्वृद्धव्यवहारादेव शब्दार्थसंबन्धव्युत्पत्तिरनिच्छतापि युक्तिवशादेष्टव्येत्यर्थः ॥

(उद्द्योतः) समाधत्ते—विषम इति । शुक्लः कृष्ण इति दृष्टान्तो विषम इत्यर्थः । तत्र गुणिमात्राक्षेपस्तथा प्रतीतिश्च, अत्र तु नियमेन विशेषप्रतीतिरिति वैषम्यमिति भावः ॥ तदाह—यथा शुक्ल इत्यादि ॥ द्रव्यमात्रमिति । सुबर्थसंख्ययाऽऽक्षिप्येतेत्यर्थः ॥ निर्दिश्येतार्थ इत्यस्य तदेति शेषः ॥ क्वचित्पाङ्कस्तत्पाठः ॥ भवति चेति । विशेषसंप्रत्यय इत्यनुषङ्गः । तस्माद्वात्वादीनामप्यर्थादेशनमावश्यकं, न च तत्संभवतीति स्वाभाविकत्वपक्ष एवाश्रयणीयः । तदाह—तस्मादिति ॥

(समाधानान्तरभाष्यम्)

अप्रवृत्तिः खल्वप्यर्थादेशनस्य । बहवो हि शब्दा येषामर्था न विज्ञायन्ते—जर्भरी तुर्फरीतू ॥ अन्तरेण खल्वपि शब्दप्रयोगं बहवोऽर्था गम्यन्ते—अक्षिनिकोचैः पाणिविहारैश्च ॥ न खल्वपि निर्ज्ञातस्यार्थस्यान्वाख्याने किंचिदपि प्रयोजनमस्ति । यो ब्रूयात्पुरस्तादादित्य उदेति पश्चादस्तं गच्छति, मधुरो गुडः, कटुकं शृङ्गवेरमिति । किं तेन कृतं स्यात् ॥

(प्रदीपः) येषामर्था न ज्ञायन्त इति । स्वर्गापूर्वदेवतादिशब्दानामर्थाः प्रत्यक्षापरिच्छेद्यत्वादिदंतया न ज्ञायन्ते तत्र तेषां कथमर्था निर्दिश्येरन्नित्यर्थः ॥ त्रैविद्यव्यवहारात् तेषामर्थो विज्ञायत एव ॥ अक्षिनिकोचैरिति । यथैतैर्व्यवहारवशादर्था गम्यन्ते तथा शब्दैरपीति भावः ॥ न खल्वपीति । साध्वसाधुसंकरनिरासाय शास्त्रारम्भान्नास्ति लोकव्यवहारावगतार्थान्वाख्याने प्रयोजनमिति भावः ॥

(उद्द्योतः) इदंतया, तत्तद्वैजात्यरूपेण ॥ विज्ञायत एवेति । तत्तत्पदवाच्यः कश्चिदर्थ इत्येवंरूपेणेत्यर्थः ॥ भाष्ये—जर्भरीति । यद्यपि जर्भरीत्यस्य भर्तारावित्ति तुर्फरीतू इत्यस्य हन्तारावित्यर्थो निरुक्तकारैर्दर्शितस्तथापि सर्वजनप्रसिद्धत्वाभावात् प्रकृतिप्रत्ययविभागेनान्वाख्यानासंभवाच्च न विज्ञायन्त इत्युक्तं भगवता ॥ अन्वाख्याने । वाक्यभेदेन विधाने । तस्माल्लोकसिद्धानामेव निमित्तत्वेनान्वाख्यानमित्येव युक्तमिति भावः ॥ भाष्ये—शृङ्गवेरम् आर्द्रकम् ॥ किं तेन कृतं स्यादिति । अनेनैषां प्रयोगानर्हत्वं सूचयति । यदि तु माधुर्यातिशयादिप्रतीतिः प्रयोजनं तदा तु प्रयोक्तव्यमेवेति बोध्यम् ॥

(११९२ लाघवदर्शकवार्तिकम् ॥ ३ ॥)

॥ * ॥ वावचनानर्थक्यं च स्वभावसिद्धत्वात् ॥ * ॥

(भाष्यम्) वावचनमनर्थकम् ॥ किं कारणम् ? । स्वभावसिद्धत्वात् । इह द्वौ पक्षौ वृत्तिपक्षश्चावृत्तिपक्षश्चेति । स्वभावतश्चैतद्भवति—वाक्यं च समासश्च । तत्र स्वाभाविके वृत्तिविषये नित्ये समासे प्राप्ते वावचनेन किमन्यच्छक्यमभिसंबन्धुमन्यदतः संज्ञायाः । न च संज्ञाया भावाभावाविष्येते । तस्मान्नार्थो वावचनेन ॥

(प्रदीपः) वावचनानर्थक्यं चेति । इह व्यपेक्षायां समासो न भवति, एकार्थीभावे वाक्यं नेति विविक्तविषयत्वादनयोर्बाध्यबाधकभावो न भविष्यतीति नार्थो विकल्पेन । एकार्थानां विकल्पनात् ॥ न च संज्ञाया इति । एकार्थी-

भावे चित्रगुरित्येवेष्यते, न तु चित्रा गाव इत्येवम्। तथा राजपुरुष इतीष्यते, न तु राज्ञः पुरुष इति। ऐकपद्यमैकस्वर्यमेकविभक्तित्वं च सर्वैकार्थीभाव इष्यत इत्यर्थः॥

(उद्द्योतः) अर्थाभिधानस्य स्वाभाविकत्वपक्षे लाघवमपि दर्शयति—**वावचनानर्थक्यं चेति**। वाक्यभेदोपि न, वावचनानर्थक्यं चेत्यर्थः। वावचनपदेन महाविभाषोच्यते। इदमुपलक्षणं निषेधशास्त्राणां नित्यं क्रीडेत्यादिनित्यग्रहणस्य च॥ **किमन्यदिति**। न च विशेषणीभूतसामर्थ्येनैव संबन्धस्तस्य लोकस्वभावसिद्धत्वेनाविधेयतया विशेषणतया च विकल्पानन्वयादिति भावः॥ **न च संज्ञाया इति**। एकार्थीभावविषये इति शेषः। तदाह—**एकार्थीभावे इति**॥

(अथ वृत्तिलक्षणभेदवर्णनाधिकरणम्)

(कार्यशब्दिकपक्षाक्षेपभाष्यम्)

अथ ये वृत्तिं वर्तयन्ति, किं त आहुः?॥

(प्रदीपः) **अथेति**। कार्यशब्दिका वाक्यादेव विकल्पेन वृत्तिं निष्पाद्यां मन्यमानाः किं वृत्तेर्लक्षणं कुर्वन्तीति प्रश्नः॥ नैत्यशब्दिकास्तु वृत्तिवाक्ये नित्ये विविक्तविषये मन्यन्ते॥

(उद्द्योतः) अर्थाभिधानस्य वाचनिकत्वपक्षे आह भाष्ये—**अथ ये वृत्तिं वर्तयन्तीति**। **वृत्तिम्**, एकार्थीभावरूपां, वर्तयन्ति शास्त्रेण निष्पादयन्ति ये शास्त्रैकगम्यं सामर्थ्यं मन्यन्ते इत्यर्थः। अयं भावः—एकार्थीभावकृतविशेषाः समर्थसूत्रविधेयाः। सुबन्तं सुबन्तेन सह सामर्थ्यवद्भवति समर्थं च समाससंज्ञकमित्यर्थः। एवं च विभाषाधिकारादि सर्वं चरितार्थम्। समासादौ वृत्तिव्यवहारस्तु वृत्तिवृत्तिमतोरभेदोपचाराद्बोध्यः॥ **किं ते इति**। स्वाभाविकत्वमते एकार्थीभावरूपा वृत्तिर्लोकत एव सिद्धेति न किंचित्तत्र वक्तव्यम्। ये तु शास्त्रनिष्पाद्यां मन्यन्ते ते किं तत्स्वरूपं शास्त्रविधानयोग्यमाहुरिति प्रश्नः॥ तद्ध्वनयन्व्याचष्टे—**कार्यशब्दिका इति**। शब्दानां शास्त्रकार्यत्वे तेषां लोके सिद्ध्यभावादर्थसंबन्धस्य लोकतो ज्ञानासंभवेन तस्यापि शास्त्रविधेयत्वमेव वाच्यम्, एवं च तद्विकल्पादिबोधकतया विभाषापदादि चरितार्थम्॥ एवं च शास्त्रैकगम्यत्वात्सामर्थ्यरूपवृत्तेर्लक्षणमपि कार्यमिति भावः॥ **वृत्ति**, वृत्त्याश्रयसमासादिरूपाम्॥ तेषां मते वृत्तिव्यवहारप्रयोजकं वृत्तिधर्मवृत्तिरूपं सामर्थ्यमपि विधेयमेवेति भावः॥ **किंवृत्तेरिति**। सामर्थ्यस्येत्यर्थः॥ **नैत्यशब्दिकास्त्विति**। कार्यं शब्दमाह। नित्यं शब्दमाहेत्यर्थे तदाहेति माशब्दादिभ्य इति ठक्। शब्दस्य नित्यत्वे तदर्थसंबन्धस्यापि नित्यतया तन्मते उभयोरपि लोकत एव विविक्तविषयत्वेन सिद्ध्यैकोपस्थितिजनकतावत्समुदायस्यैव वृत्तित्वेन तद्गतैकोपस्थितिजनकतासामर्थ्यं लोकसिद्धमिति न तन्मते प्रश्न इति भावः॥

(समाधानभाष्यम्)

परार्थाभिधानं वृत्तिरित्याहुः॥

(प्रदीपः) **परार्थाभिधानमिति**। परस्य शब्दस्य योर्थस्तस्याभिधानं शब्दान्तरेण यत्र सा वृत्तिरित्यर्थः। यथा राजपुरुष इत्यत्र राजशब्देन वाक्यावस्थायामनुक्तः पुरुषार्थोऽभिधीयते॥

(उद्द्योतः) **परस्य शब्दस्येति**। प्रधानार्थकशब्दस्योपसर्जनशब्दस्य वेत्यर्थः॥ **यत्रेति**। समासादिषु वृत्तिव्यवहारादिति भावः। एवं च तन्निष्ठशब्दान्तरकरणकपदार्थाभिधायकत्वं तेषां स्वाश्रयत्वेन वृत्तिव्यवहारप्रयोजकं सामर्थ्यमिति फलितम्। तच्च स्वार्थविशेषणकपुरुषार्थोपस्थितौ राजपदशक्तिज्ञानस्य सहकारित्वाद्बोध्यम्॥

(आक्षेपभाष्यम्)

अथ तेषामेवं ब्रुवतां किं जहत्स्वार्था वृत्तिर्भवति, आहोस्विदजहत्स्वार्था भवति?॥ किं चातः?। यदि जहत्स्वार्था वृत्तिः; राजपुरुषमानयेत्युक्ते पुरुषमात्रस्यानयनं प्राप्नोति, औपगवमानयेत्युक्ते अपत्यमात्रस्येति॥ अथाजहत्स्वार्था वृत्तिः, उभयोर्विद्यमानस्वार्थयोर्द्वयोर्द्विवचनमिति द्विवचनं प्राप्नोति॥ का पुनर्वृत्तिर्न्याय्या?॥

(प्रदीपः) **अथ तेषामिति**। नित्यशब्दवादिपक्षे तु राजपुरुषादीनि वाक्यविषयपदसरूपावयवानि वर्णवदनर्थकोपलभ्यमानावयवानि तत्त्वतो निरवयवान्येव केवलमसत्यप्रक्रियाश्रयेणान्वाख्यायन्ते॥ जहति पदानि स्वार्थं यस्यां सा जहत्स्वार्था॥ **पुरुषमात्रस्येति**। राजपदोपादानमनर्थकमिति चेत् तदा पर्यायत्वं पुरुषराजपुरुषशब्दयोर्वियावकशब्दयोरिव स्यादित्यदोषः॥ **द्विवचनं प्राप्नोतीति**। प्लक्षन्यग्रोधाविति यथा॥

(उद्द्योतः) भाष्ये वृत्तिवर्तनवादिनामित्यर्थकतेषांपदस्य व्याख्यानं दर्शयति—**नित्येत्यादि**॥ पदसरूपावयवत्वमपि न वास्तवमित्याह—**वर्णवदिति**। वर्णेष्विवात्राप्यवयवभ्रम इति भावः। तदेवाह—**तत्त्वत इति**॥ नन्वेवं तत्पक्षे **समर्थः पदविधिरि**त्याद्यसंगतं तत्राह—**केवलमसत्येति**। वाक्यविषयपदसारूप्यादेव तद्वदर्थमप्यारोप्यान्वाख्यानमिति भावः॥ एवं च तत्पक्षे तेषामर्थस्यैवाभावात् तत्र त्यक्तत्वात्यक्तत्वसंदेहाभावादथ **तेषामि**त्युक्तमिति भावः॥ केचित्तु नित्यशब्दवादेप्युपलभ्यमानावयवानां नैरर्थक्ये समुदायस्य निरवयत्वे च मानाभावः। न चैतावता नित्यत्वहानिः, शास्त्रानिष्पाद्यत्वरूपनित्यतायास्तथाप्यहानात्। न चैवं भाष्येऽथ तेषामित्यसंगतं स्यात्। शास्त्रनिष्पाद्यत्वं द्वेधा सावयवस्यैव लोकसिद्धत्वेनानादितया निरवयवतया वा। तत्राद्येऽजहत्स्वार्थैव, द्वितीये तु तेषामर्थाभाव एवेति जहत्स्वार्थैवेति वाक्यवदेव मतभेदेन नियमासन्देहाभावेन तदुक्तिरिति वक्तुं शक्यत्वात्। तत्राप्यन्त्यपक्षे आरोपितमर्थवत्त्वादि शास्त्रप्रवृत्तिमात्रफलकं, तेन महासुन्दर इत्यादावात्वमित्यन्यदेतत्॥ शास्त्रानिष्पाद्यत्वमते तु स्वार्थत्यागेऽर्थान्तराभिधायकत्वानुपपत्तिः। अर्थत्यागे तु पुरुषमात्रस्यानयनापत्तिरिति प्राहुः॥ **जहतीति** शत्रन्तम्। बहुवचनं प्रयोगबहुत्वाभिप्रायेण॥

स्वार्थं, तस्येन प्रसिद्धम् ॥ जहति स्वानि पदानि यमिति जहत्स्वः जहत्स्वोऽर्थो यस्याः सेत्यर्थ इत्यन्ये ॥ इष्टेति । पष्ठ्यभावेन संबन्धाप्रतीत्या प्रातिपदिकार्थमात्रवृत्तित्वादित्यभिमानः ॥

(समाधानभाष्यम्)

जहत्स्वार्था ॥

(प्रदीपः) **जहत्स्वार्थेति** । नहि स्वार्थमजहतः स्वेनार्थेन वशीकृतस्यार्थान्तरोपादानं घटते ॥

(उद्द्योतः) **स्वेनार्थेनवशीकृतस्येति** । स्वार्थमात्रोपस्थाने व्यासक्तस्येत्यर्थः ॥ **अर्थान्तरोपादानम्** । अर्थान्तरं प्रति विशेषणत्वम् । यद्वाऽर्थान्तरस्य स्वं प्रति विशेष्यत्वेनोपादानम् । न च पृथगुपस्थितयोः पश्चादन्वयः, संबन्धबोधकविभक्त्यभावात् । अभेदान्वयस्तु बाधित एवानुभवबाधितश्चेत्यभिमानः ॥

(आक्षेपभाष्यम्)

युक्तं पुनर्जहत्स्वार्था नाम वृत्तिः स्यात्? ॥

(प्रदीपः) **युक्तं पुनरिति** । उपात्तस्यार्थस्य त्यागाभावात् । अभिनेबोऽप्यस्य ॥

(उद्द्योतः) **उपात्तस्येति** । अर्थोपादानस्येव तत्त्यागस्याप्येतन्मते वचनं विनाऽशक्यत्वादिति भावः ॥

(समाधानभाष्यम्)

बाढं युक्तम् । एवं हि दृश्यते लोके—पुरुषोयं परकर्मणि प्रवर्तमानः स्वं कर्म जहाति । तद्यथा—तक्षा राजकर्मणि प्रवर्तमानः स्वं तक्षकर्म जहाति । एवं युक्तं यद्राजा पुरुषार्थे वर्तमानः स्वमर्थं जह्याद् । उपगुश्चापत्यार्थे वर्तमानः स्वमर्थं जह्यात् ॥

(प्रदीपः) **बाढं युक्तमिति** ॥ परार्थवृत्तित्वादेव ॥ अत्रैव दृष्टान्तमाह—**तक्षा राजकर्मणीति** । यदा राज्ञा तक्षा वृत्यादौ नियुज्यते तदा स्वकं कर्म जहाति ॥

(उद्द्योतः) **परार्थवृत्तित्वादेव** । परार्थं प्रति विशेषणत्वेनोपस्थितिविषयत्वादेव ॥

(आक्षेपस्मारणभाष्यम्)

ननु चोक्तं राजपुरुषमानयेत्युक्ते पुरुषमात्रस्यानयनं प्राप्नोति । औपगवमानयेत्युक्तेऽपत्यमात्रस्येति ॥

(समाधानभाष्यम्)

नैष दोषः । जहदप्यसौ स्वार्थं नात्यन्ताय जहाति, यः परार्थविरोधी स्वार्थस्तं जहाति । तद्यथा—तक्षा राजकर्मणि प्रवर्तमानः स्वं तक्षकर्म जहाति, न तु हिक्कितश्वसितकण्डूयितानि । न चायमर्थः परार्थविरोधी विशेषणं नाम । तस्मात्तन्न हास्यति ॥

(प्रदीपः) **नात्यन्तायेति** । त्यागमात्रमभिसंधाय जहत्स्वार्थेत्युच्यते, न तु सर्वात्मना त्यागः । परोपकाराय तस्योपादानात् । सर्वथा च स्वार्थत्यागे परोपकारासंपादनादनुपादानमेव प्रयोजनाभावात्तस्य स्यादित्यर्थः ॥ **न तु हिक्कितेति** । तेषां प्राणिधर्मत्वात्तत्त्यागे राजकर्मैव तस्य विच्छिद्येतेत्यर्थः ॥ **नचायमर्थ इति** । वाक्येपि राजार्थस्य विशेषणत्वात् कस्तस्य वृत्तौ विशेष इति चेत् । वाक्ये स्वविशेषणसंबन्धप्रतिपत्तौ सामर्थ्याविघातः । वृत्तावुपसर्जनीभूतेन स्वार्थेन प्रधानार्थस्योपकारात् स्वविशेषणप्रतिपत्तौ सामर्थ्यहानिः ॥

(उद्द्योतः) **नात्यन्तायेत्यव्ययम्** ॥ **त्यागमात्रमिति** । स्वार्थविशेष्यत्वरूपांशस्य त्यागेन तथा व्यवहार इति भावः ॥ विषयतापि शब्दशक्येति विस्तरेण मञ्जूषायां निरूपितम् ॥ **परोपकारायेति** । परस्य पुरुषादेरितरसंबन्धव्यवच्छेदरूपोपकारायेत्यर्थः ॥ हिक्कितादीनां राजकर्मानुपकारकत्वाद्विषम उपन्यासस्तत्राह—**तेषामिति** । प्राणापगमे एव तत्त्यागादिति भावः ॥ भाष्ये—**न चायमर्थः परार्थविरोधीति** । राजपदेन परार्थस्य पुरुषरूपार्थस्यास्कन्दने तद्विशेषणत्वेन राजरूपार्थोपस्थितौ राजरूपोर्थः स्वतो न विरोधी, किं तु स्वगतं विशेष्यत्वमेव विरोधि, अतस्तच्च हास्यति, किं तु स्वगतं विशेष्यत्वमेव विरोधिभूतं त्यजतीत्यर्थस्तद्ध्वनयन् व्याचष्टे—**विशेषणं नामेति** । अन्यथा विशेषणविशिष्टपुरुषोपस्थितिर्न स्यादिति भावः ॥ अमुमेवार्थं शङ्कोत्तराभ्यां विशदयति—**वाक्येपीति** ॥ **स्वविशेषणेति** । इदमुपलक्षणं संख्याविशेषसंबन्धप्रतीत्यप्रतीत्योः । एवं पुरुषपदमपीतरान्वितमेव स्वार्थमुपस्थापयति न केवलम् । अतो न भार्याया इत्याद्यन्वयस्तत्र ॥ अत्रायं भावः—पदानां तत्तद्विषयताविशिष्टेर्थे शक्तिः । अत एव बोधे विषयतानियमः । एवं च राजपदादे राजत्वनिष्ठप्रकारतानिरूपितविशेष्यत्वावच्छिन्नं स्वार्थस्तत्र समासे विशेष्यत्वांशत्याग इत्येतावता जहत्स्वार्थत्वमिति ॥ अत्र च बीजं समुदायशक्तिः । एवं चावयवशक्तिसहकृतसमुदायशक्त्या विशिष्टैकोपस्थितिरिति तत्त्वम् ॥

(समाधानान्तरभाष्यम्)

अथ वाऽन्वयाद्विशेषणं भविष्यति । तद्यथा—'घृतघटस्तैलघट' इति । निषिक्ते घृते तैले चान्वयाद्विशेषणं भवति—अयं घृतघटोऽयं तैलघट इति ॥

(प्रदीपः) **अन्वयादिति** । राजशब्दः स्वार्थनिमित्तं पुरुषार्थे विशेषमाधाय स्वार्थं जहाति, न च तन्निमित्तं विशेषदर्शनं निवर्तते पुरुषे । यथाग्निसंबन्धजनितपाकजरूपादिनिवृत्तिर्घटेऽग्निसंयोगे निवृत्तेपि न भवतीत्यर्थः ॥ **विशेषणमिति** । विशेषः पुरुषगतो भविष्यतीत्यर्थः ॥

(उद्द्योतः) भाष्ये—**अथ वाऽन्वयाद्विशेषणं भविष्यतीति** । **विशेषणं** विशेषकः इतरव्यावर्तक इत्यर्थः । तद्व्याचष्टे—**राजशब्द इति** । वाक्यवृत्तस्वजन्योपस्थितिविषयार्थनिमित्तं विशेषं राजसंबन्धरूपं पुरुषपदजोपस्थितिविषये पुरुषे आधाय पुरुषं

तद्वैशिष्ट्येन पुरुषपदेनोपस्थितिविषयं कृत्वा **स्वार्थं** तस्य स्वार्थत्वं स्वजन्योपस्थितिविषयत्वं **जहाति** तद्वाक्यनिष्पन्नवृत्तावित्यर्थः ॥ अयं हि वाक्याद्वृत्तेर्निष्पत्तिं मन्यते ॥ **न च तन्निमित्तमिति ।** एवं च राजशब्दात्तदर्थप्रतीत्यभावेपि तच्छब्दान्वयमात्रेण वाक्ये यादृशविशेषणविशिष्टः पुरुषः शब्दात्प्रतीतस्तादृशस्यैवात्राप्युपस्थितिरित्यनुमानात्पुरुषपदस्य तथा शक्तिग्रह इति भावः ॥ **विशेषः पुरुषगत इति ।** राजपदकृतो वाक्ये पुरुषगतो विशेषो भविष्यति न निवर्त्स्यत इत्यर्थः । एवं च राज्ञो राजादिपदजोपस्थितिविषयत्वाभावेन जहत्स्वार्थत्वमिति बोध्यम् ॥

(समाधानान्तरबाधकभाष्यम्)

विषम उपन्यासः । भवति हि तत्र या च यावती चार्थमात्रा । अङ्ग हि भवानग्नौ निष्टप्य घृतघटं तृणकूर्चेन प्रक्षालयतु न गंस्यते स विशेषः ॥

(समाधानसाधकभाष्यम्)

यथा तर्हि मल्लिकापुटश्चम्पकपुट इति । निष्कीर्णास्वपि सुमनःसु अन्वयाद्विशेषणं भवति—अयं मल्लिकापुटः, अयं चम्पकपुट इति ॥

(प्रदीपः) **मल्लिकापुट इति ।** आमोदान्वयाद्विशेषावगतिरिति भावः ॥

(उद्योतः) [यथा पुष्पाणामभावेपि गन्धान्वयमात्रेण पूर्वतनीं पुष्पसत्तामनुमाय मल्लिकापुट इत्यादिव्यवहारस्तथा वृत्तौ राजपदस्यार्थाभावेपि वाक्यदृष्टसार्थकराजशब्दवर्णानुपूर्वीसत्त्वमात्रेण वाक्ये यथा राजसंबन्धवतः पुरुषस्यैव प्रतीतिस्तथेहापि राजसंबन्धवतः पुरुषस्यैव पुरुषपदात् प्रतीतिरित्यर्थः । तत्सादृश्यमात्रेणैवार्थवत्त्वप्रतीत्याऽऽरवाद्यपीति न दोषः ॥]

(समाधानान्तरभाष्यम्)

अथ वा समर्थाधिकारोयं वृत्तौ क्रियते । सामर्थ्यं नाम भेदः, संसर्गो वा ॥ अपर आह—भेदसंसर्गौ वा सामर्थ्यमिति ॥ कः पुनर्भेदः संसर्गो वा ?। इह राज्ञ इत्युक्ते सर्वं स्वं प्रसक्तम्, पुरुष इत्युक्ते सर्वः स्वामी प्रसक्तः । इहेदानीं राजपुरुषमानयेत्युक्ते राजा पुरुषं निवर्तयत्यन्येभ्यः स्वामिभ्यः, पुरुषोपि राजानमन्येभ्यः स्वेभ्यः । एवमेतस्मिन्नुभयतो व्यवच्छिन्ने यदि स्वार्थं जहाति कामं जहातु न जातुचित्पुरुषमात्रस्यानयनं भविष्यति ॥

(प्रदीपः) **वृत्तौ क्रियत इति ।** यदि च वृत्तौ भेदसंसर्गौ न स्यातां तदा सामर्थ्यमेव न स्यात् तदात्मकत्वात् सामर्थ्यस्येत्यर्थः । तत्र भेदः संसर्गाविनाभावित्वादनुमीयमानसंसर्गः सामर्थ्यम्, संसर्गो वा भेदाविनाभाव्यनुमेयभेदः ॥ उभौ वा यौगपद्येनाश्रीयमाणौ सामर्थ्यमित्यर्थः ॥ **सर्वं स्वमिति ।** राज्ञ इति षष्ठ्या संबन्धिमात्रस्याक्षेपात् ॥ **सर्वः स्वामीति ।** यदा पुरुषस्य पारतन्त्र्यं प्रमाणान्तरेण प्रतिपन्नं तदपेक्ष्यैतदुच्यते। अन्यथा पुरुष इत्युक्तेऽस्तीति प्रतीतिः स्यात्, न तु स्वामिमात्राक्षेपः । तत्र भेदपक्षे राजा पुरुषं स्वाम्यन्तरेभ्यो निवर्त्य स्वार्थं जहाति । पुरुषस्त्वजहदपि स्वार्थं स्वान्तरेभ्यो राजानं निवर्तयतीति । ततश्च कृतकार्यस्य भवतु राजार्थस्य निवृत्तिः । अकृतकार्यस्य निवृत्तौ वृत्तिरेव न स्यात् । एवं संसर्गेपि योज्यम् ॥ **उभयत इति ।** उभयस्मिन् परस्परेणावच्छिन्ने इत्यर्थः ॥

(उद्योतः) भाष्ये—**अथ वेति ।** समभिव्याहृतपदार्थनिरूपितसंसर्गतदतिरिक्तभेदैतदुभयवान् योर्थः स समासेन प्रत्याय्यते तादृशपुरुषाद्युपस्थितावेव राजादिपदं तात्पर्यग्राहकम् ॥ **अन्वयादिति** पक्षे पुरुषपदं राजसंबन्धवत्पुरुषत्वेनोपस्थापकम् । इह तु पुरुषपदात्पुरुषत्वेनैव पुरुषविशेषोपस्थितिरिति भेदः ॥ **सामर्थ्यमेव न स्यादिति ।** अन्यथा राज्ञः पुरुषोऽश्वश्च राज्ञः पुरुषो भार्यायाश्चेतिवद् राजपुरुषोऽश्वश्च राजपुरुषो भार्यायाश्चेत्यपि स्यात्। अत एकार्थीभावरूपं स्वाभाविकं सामर्थ्यमाश्रयतापीदमवश्यं वक्तव्यम्—'भेदसंसर्गवानेवार्थो वृत्त्योपस्थाप्यते' इति, तदाह—**तदात्मकत्वादिति ।** एवं च भेदसंसर्गवदर्थप्रतिपादकत्वमेवैकार्थीभावसामर्थ्यमित्यर्थः । तत्र युक्तिरुक्तैव ॥ **तत्र भेद इति ।** स्वत्वसमानाधिकरणो राजभिन्नस्वामिकभेदो राजसंसर्गव्याप्यः । एवं वृत्त्युपस्थाप्यराजसंबन्धवद्व्यक्तिगतराजसंबन्धो राजभिन्नस्वामिकभेदव्याप्य इति भावः ॥ एवं च भेदवद्व्यक्तिबोधे सा राजसंसर्गवत्यपीति तद्वती व्यक्तिरपि बुद्धैव । एवमितरत्रापीति तात्पर्यम् ॥ **उभौ वा यौगपद्येनेति ।** अयं भावः—उक्तरीत्योभयोः समनियतत्वेन विनिगमनाविरह इति । एवं च भेदवदर्थप्रत्यायकत्वं सामर्थ्यम् । न च संसर्गवतोपि प्रत्ययेनासंभवो लक्षणस्येति वाच्यम्। तद्व्याप्यत्वात्तद्वतोपि प्रत्ययेनादोषात्।लक्षणस्यावधारणागर्भत्वात्। संसर्गवदर्थप्रत्यायकत्वं वा सामर्थ्यम् । भेदवतः प्रतीतिस्तद्व्याप्यत्वात् । तेनोक्तरीत्या नासंभवः ॥ एतत्क्लेशपरिहारायापरेणोभयगर्भसामर्थ्यलक्षणमुक्तम्। **सर्वं वाक्यं सावधारणमि**तिन्यायबाधश्च नेति तद्भावः ॥ **सर्वस्वं प्रसक्त**मिति भाष्यस्य प्रसक्तं सर्वस्वं वाक्ये प्रयुज्यत इति शेषः ॥ पुरुषस्य स्वामिनि नित्यसाकाङ्क्षत्वाभावादाह—**यदेति ॥ तत्र भेदपक्षे इति ।** भेदघटितसामर्थ्यलक्षणपक्षे इत्यर्थः ॥ **स्वाम्यन्तरेभ्यो निवर्त्येति ।** राज्ञः पुरुषो भार्यायाश्चेत्यादाविव भार्यादिसंबन्धवद्व्यक्त्युपस्थापकत्वान्निवर्त्येत्यर्थः । एतावतैव परार्थाभिधायकत्वमिति भावः ॥ **निवर्तयतीति ।** राज्ञः पुरुषोऽश्वश्चेत्यादावश्वादिरूपस्वान्तरनिरूपितस्वामित्ववद्व्यक्त्युपस्थापकत्वं राजपदस्य निवर्तयतीत्यर्थः । इदं दृष्टान्तार्थम् । यथा विशेषणत्वेनानन्वितोपि पुरुषो राजानं स्वान्तरेभ्यो निवर्तयति, एवं राजा विशेषणत्वेनानन्वित एव पुरुषं स्वाम्यन्तरेभ्यो निवर्तयिष्यतीति भावः ॥ **भवतु राजार्थस्येति ।** द्योतकतामात्रेण चारितार्थ्याद् राजपदात्तदनुपस्थितिरेव निवृत्तिरित्यर्थः ॥ **वृत्तिरेव न**

स्यादिति । अर्थवत्त्वाभावेन सुबन्तत्वाभावादिति भावः ॥ **एवं संसर्गेपीति** । संसर्गघटितलक्षणपक्षेपीत्यर्थः । भेदस्य तद्याप्यत्वात्स्वाम्यन्तरेभ्यो निवर्त्येत्यादि वोध्यम् ॥ भाष्ये—**अन्येभ्यः स्वामिभ्यो निवर्त्तयतीत्युक्त्या** स्वस्वरूपस्वामिनो न निवर्त्तयतीत्यर्थलाभात्संसर्गो वोधितः ॥ एतेन **कः पुनर्भेदः संसर्गो** वेति प्रश्ने भेदप्रतिपादनेपि संसर्गाप्रतिपादनाद् न्यूनतेत्यपास्तम् ॥ **किं चान्येभ्यः स्वामिभ्यो निवर्त्तयतीत्य**नेनान्यस्वामिसंबन्धनिवृत्तं पुरुषं वोधविषयीकरोतीत्यर्थकेन भेदादेः शाब्दबोधाविषयत्वं सूचयति ॥ **पुरुषो राजानमन्येभ्य** इति दृष्टान्तार्थम् । इतोपि तयोर्वोधाविषयत्वं वोध्यम् । नहि राज्ञि तद्भेदतत्संसर्गभानं कस्यापि संमतमिति दिक् ॥ **स्वार्थं जहातीति** । उपसर्जनपदमिति शेषः ॥ यत्तु भेदसंसर्गौ समासवाच्याविति ॥ तन्न, भेदप्रकारकबोधाननुभवात् ॥ किं च वृत्तिवर्त्तनवादे जहत्स्वार्थत्वं वृत्तेर्व्युत्पादयितुमेष ग्रन्थः । तत्र संसर्गस्य समासवाच्यत्वे तत्र प्रतियोगित्वेन पूर्वपदार्थस्यान्वयावश्यकत्वे जहत्स्वार्थत्वभङ्ग एव स्यात् । उक्तरीत्या भाष्याक्षरस्वारस्यविरोधाच्च । तस्माद्वेदान्तिमते तत्त्वमस्यादिवाक्यादावखण्डार्थबोध इव वृत्तौ बोधः । अयमेव चैकार्थीभावः । तन्नये वाक्ये पदेषु तत्तत्कार्यप्रवृत्तिघटके आत्वादिप्रवृत्तिरिति सुधियो विभावयन्तु ॥ इमौ भेदसंसर्गौ द्वन्द्वेपि, समूहविशेषस्यैव प्रतीतेः । बहुव्रीहावपि संबन्धित्वेन व्यक्तिविशेषस्यैव भानमित्याभाति ॥ राजपुरुषयोरेव व्यवच्छिन्नत्वादुभयतो व्यवच्छिन्नमन्यन्नास्तीत्यत आह—**उभयस्मिन्निति** । सार्वविभक्तिकत्वात्सप्तम्यर्थे तसिरित्यर्थः ॥

(अथाजहत्स्वार्थाङ्गीकारभाष्यम्)

अथ वा पुनरस्त्वजहत्स्वार्था वृत्तिः ॥

(आक्षेपभाष्यम्)

युक्तं पुनरिदं यदजहत्स्वार्था नाम वृत्तिः स्यात्?॥

(प्रदीपः) **युक्तं पुनरिति** । स्वमर्थमजहतस्तेन वशीकृतस्यार्थान्तरोपादानमयुक्तमिति भावः ॥

(समाधानभाष्यम्)

बाढं युक्तम् । एवं हि दृश्यते लोके भिक्षुकोयं द्वितीयां भिक्षां समासाद्य पूर्वां न जहाति । संचयायैव प्रवर्तते ॥

(प्रदीपः) **संचयायेति** । एवं शब्दोपि क्वचिद्विषय एकार्थः क्वचिदनेकार्थ इत्यर्थः ॥

(उद्द्योतः) एवं च शब्दार्थस्य नियतत्वात्संचयोऽनुपपन्न इत्यत आह—**एवमिति** । राजनिष्ठविशेष्यताया अत्यागेपि पुरुषनिष्ठविशेष्यतानिरूपितविशेषणताया राजपदार्थतास्वीकार एव संचय इति भावः ॥ एवं च स्वार्थमात्रोपस्थित्या न कृतार्थम्, किं त्वितरान्वितमेव स्वार्थमुपस्थापयतीत्यत्र पक्षे **जहदप्यसौ नात्यन्तायेति** पक्षे च परार्थाभिधानमित्यस्य परार्थान्वितस्वार्थाभिधानमित्यर्थः । मध्यमयोस्तु परार्थतात्पर्यग्राहकत्वमिति निष्कर्षः ॥

(आक्षेपस्मारणभाष्यम्)

ननु चोक्तम्—'उभयोर्विद्यमानस्वार्थयोर्द्वयोर्द्विवचनमिति द्विवचनं प्राप्नोति—' इति ॥

(उद्द्योतः) इतर आशयानभिज्ञः शङ्कते भाष्ये—**ननु चेति** ।

(प्रत्याक्षेपभाष्यम्)

कस्याः पुनर्द्विवचनं प्राप्नोति ? ॥

(प्रदीपः) **कस्या इति** । एकया विभक्त्या गुणप्रधानभूतस्यार्थद्वयस्य प्रतिपादयितुमशक्यत्वादिति प्रश्नः ॥

(उद्द्योतः) कस्या अपि भवतु द्वे अपि वा पर्यायेण भवेतां किं प्रश्नेनेत्यत आह—**एकयेति** ॥ **गुणप्रधानभूतस्येति** । परस्परमित्यादिः ॥

(आक्षेपाशयभाष्यम्)

प्रथमायाः ॥

(प्रदीपः) **प्रथमाया इति** । प्रधानानुविधायित्वाद् गुणानां प्रधानविभक्तिः प्रथमा गुणेनापि प्रतिपत्तव्येति भावः ॥

(उद्द्योतः) ननु प्रथमायां को हेतुरत आह—**प्रधानेति** ॥

(समाधानभाष्यम्)

न प्रथमासमर्थो राजा ॥

(प्रदीपः) **न प्रथमासमर्थ इति** । प्रथमाद्विवचन उत्पद्यमाने संबन्धासंप्रत्ययाद् गुणप्रधानभाव एव न प्रतीयेत ॥

(आक्षेपाशयान्तरभाष्यम्)

षष्ठ्यास्तर्हि प्राप्नोति ॥

(प्रदीपः) **षष्ठ्यास्तर्हीति** । संबन्धस्य प्रत्याय्यत्वात् तस्य चोभयाधिष्ठानत्वात् ॥

(समाधानभाष्यम्)

न षष्ठीसमर्थः पुरुषः ॥

(प्रदीपः) **न षष्ठीति** । यदि षष्ठीद्विवचनं स्यात् तदा द्वयोरपि समकक्ष्यत्वेन संबन्ध्यन्तरापेक्षया संबन्धः प्रतीयेत ॥

(उद्द्योतः) **संबन्ध्यन्तरापेक्षयेति** । न तु राजनि पुरुषापेक्ष इति भावः ॥

(पूर्वोक्ताशयाभ्युपगमभाष्यम्)

प्रथमाया एव तर्हि प्राप्नोति ॥

(बाधकस्मारणभाष्यम्)

ननु चोक्तम्—न प्रथमासमर्थो राजा—इति ॥

(आक्षेपाशयसाधकभाष्यम्)

अभिहितः सोर्थोन्तर्भूतः प्रातिपदिकार्थः संपन्नः । तत्र प्रातिपदिकार्थे प्रथमेति प्रथमाया एव द्विवचनं प्राप्नोति ॥

(प्रदीपः) **अभिहित इति** । कश्चिदर्थोभिहितोपि नान्तर्भूतः । यथा राज्ञ इति षष्ठ्या संबन्धोभिहितो न कुत्रचिदन्तर्भावं यातः ॥ कश्चिदन्तर्भूतोपि नाभिहितः । यथा राजसख इति तत्पुरुषे राजा सखास्येत्यर्थोन्तर्भवति न त्वभिधीयते ॥ तथा कश्चिदर्थोभिहितोन्तर्भूतः । यथा पचतीति कर्ताभिधीयमानो गुणभावादन्तर्भूतः, न त्वसौ प्रातिपदिकार्थ इति त्रयमुपात्तम् । तत्र संबन्धोऽभिहितोऽन्तर्भूतः प्रातिपदिकार्थः संपन्न इति व्यतिरेकाभावात् प्रथमाद्विवचनं प्राप्नोति ॥

(उद्योतः) **न क्वचिदन्तर्भावमिति** । न राजसख इत्यादौ बहुव्रीह्यर्थ इव वाचकशब्दं विना नियमेन प्रतीतिविषयो, नापि तिङन्ते कर्तृवत् प्रकृत्यर्थे गुणभूत इत्यर्थः ॥ **गुणभावादन्तर्भूत इति** । धात्वर्थत्वात्तत्रान्तर्भूत इत्यर्थः ॥ **अभिहितोन्तर्भूत इति** । प्रथमा प्राप्नोतीत्युक्तावत्रापि प्रथमापत्तिभ्रमः स्यादतः प्रातिपदिकार्थ इत्युक्तमिति भावः ॥ **व्यतिरेकाभावादिति** । षष्ठ्यभावे हेतुरुक्तः । पृथगुपस्थितिनिबन्धनसांसर्गिकविषयताया अभानादित्यर्थः ॥ एवं च राजपुरुष इत्यादिवृत्तौ स्वस्वामिभावादेर्घट इत्यादौ घटघटत्वयोः समवायस्येव प्रकृत्युपस्थितत्वेन प्रकारतैव, विभक्त्यर्थस्यैव च प्रायः संसर्गतया भानमिति बोध्यम् ॥

(११९३ समाधानवार्तिकम् ॥ ४ ॥)

॥ * ॥ संघातस्यैकार्थ्यात्सुबभावो वा संख्यातः सुबुत्पत्तिः ॥ * ॥

(भाष्यम्) **संघातस्यैकत्वमर्थः । तेनावयवसंख्यातः सुबुत्पत्तिर्न भविष्यति ॥**

(प्रदीपः) **संघातस्येति** । इह राजपुरुषशब्दात् संघाताद्विभक्त्योत्पत्तव्यम् । तेन च संघातेनावयवार्थोपकृत एकत्वसंख्यायुक्तो विशिष्टोर्थः प्रतिपाद्यत इति तदाश्रयमेकवचनं प्रवर्तते. न तु गुणभूतावयवसंख्याश्रयं द्विवचनमित्यर्थः ॥

(उद्योतः) संघातस्यैकार्थत्वेपि धवखदिरादिसंघातवद् द्विवचनं स्यादत आह—**इहेति** ॥ **अवयवार्थोपकृत इति** । शास्त्रकृत्प्रदायलोपस्थितार्थत्यागे तद्बोधायातिरिक्तशक्तिकल्पने च मानाभावादिति भावः ॥ तत्र यद्यप्यवयवार्थस्तत्तद्विशेष्यत्वावच्छिन्न एव तथापि विशेषणत्वेन तस्या विशेष्यताया आच्छादनात्तस्या अपि विशेषणत्वेनैव प्रतीतिर्न तु स्वरूपेणेति न विशेषणाद्यन्वय इति तात्पर्यम् । वाक्ये तु प्रत्येकपदजबोधकाले राजादिगतविशेष्यतायाः स्वरूपेणैव भानमिति विशेषणाद्यन्वयो भवत्येवेति बोध्यम् ॥ **विशिष्टोर्थ इति** । विशिष्टस्यैवोपस्थितिविषयत्वादित्यर्थः ॥ इयमजहत्स्वार्था वृत्तिवर्तनवादिनस्तदवर्तनवादिनश्च तुल्या ॥ जहत्स्वार्था तु वृत्तिवर्तनवादिन एव । वृत्त्यवर्तनवादिनस्त्वखण्डानि निरवयवानि पदानीति मते उभयोरपि कदाप्यर्थाभावेन त्यक्तस्वार्थत्यर्थकजहत्स्वार्थापदप्रयोगोप्यसंगतः । सावयवानीति मते कृप्तशक्तेस्त्यागे मानाभावेनाजहत्स्वार्थैव । वृत्तिवर्तनवादिनस्तु यदर्थस्तदङ्गीकारस्तदुक्तमेव । अक्षौहिणीरथन्तरादिपदे तु जहत्स्वार्थैवेति बोध्यम् ॥

(११९४ पक्षान्तरवार्तिकम् ॥ ५ ॥)

॥ * ॥ परस्परव्यपेक्षां सामर्थ्यमेके ॥ * ॥

(व्याख्याभाष्यम्)

परस्परव्यपेक्षां सामर्थ्यमेक इच्छन्ति ॥ का पुनः शब्दयोर्व्यपेक्षा ? । न ब्रूमः—शब्दयोरिति ॥ किं तर्हि ? । अर्थयोः । इह राज्ञः पुरुष इत्युक्ते राजा पुरुषमपेक्षते ममायमिति, पुरुषोपि राजानमपेक्षते अहमस्येति । तयोरभिसंबन्धस्य षष्ठी वाचिका भवति । तद्यथा—कष्टं श्रित इति क्रियाकारकयोरभिसंबन्धस्य द्वितीया वाचिका भवति ॥

(प्रदीपः) **परस्परेति** । व्यपेक्षैवात्र सामर्थ्यम्, न त्वेकार्थीभाव इत्याहुः ॥ **का पुनरिति** । स्वं स्वमर्थं प्रति गुणभावाच्छब्दयोः परस्परव्यपेक्षा न संभवतीति प्रश्नः ॥ **अर्थयोरिति** । प्रमातृगतां व्यपेक्षामर्थे समारोप्य शब्दाः संस्क्रियन्ते ॥ **ममायमिति** । दानादिक्रियानिमित्तं राज्ञः स्वाम्यमुपजायते ॥ **अहमस्येति** । पुरुषस्य प्रतिग्रहादिनिमित्तः स्वत्वोत्पादः ॥ **क्रियाकारकयोरिति** । कारकशब्देनात्र शक्त्याधारो द्रव्यमुच्यते । क्रियाद्रव्ययोरभिसंबन्धनिमित्तत्वाच्छक्तिरेवाभिसंबन्धः । तेन कर्मशक्तेर्वाचिका द्वितीयेत्यर्थः ॥ अथ वा कारकशब्देन शक्तिरेवोच्यते । शक्तेश्च वाचिका द्वितीया । सामर्थ्यात् क्रियाकारकसंबन्धस्याप्यवगमात्तस्य वाचिकेत्युक्तम् ॥

(उद्योतः) एकार्थीभावस्यापि व्यपेक्षापूर्वकत्वात् कथमस्य पक्षान्तरत्वमत आह—**व्यपेक्षैवेति** । एकार्थीभाववादिनोपि राजपुरुषपदयोः परस्परं विना बोधाजनकत्वमूलाकाङ्क्षासत्त्वे एव तद्बलात्संबन्धांशे विशिष्टशक्तिकल्पनम् । व्यपेक्षावादिनस्त्वाकाङ्क्षावशादेव तद्भानम्, न तु विशिष्टोपस्थापकशक्तिकल्पनेति भावः ॥ ननु शब्दयोरचेतनत्वात्स्वतो व्यपेक्षाभावः, एवमर्थस्यापि । अर्थे आरोपेण सेति चेत्, शब्देप्यारोपः स्यादत आह—**स्वं स्वमिति** । एतदर्थः क इत्येव शब्दविषयाकाङ्क्षा प्रमातुः न त्वन्वयिशब्दान्तरविषया । अर्थे ज्ञाते तु कोस्यान्वय्यर्थ इत्याकाङ्क्षा प्रमातुरिति भावः ॥ नन्वन्वययोग्यार्थान्तरजिज्ञासाकाङ्क्षा । सा च प्रमातृगता नार्थगतेत्यत आह—**प्रमातृगतामिति** । तस्याश्च तदुपस्थापितार्थे एवारोपो न तु गुणभूते शब्द इति भावः ॥ अर्थबोधोत्तरमेवास्यान्वय्यर्थः क इति जिज्ञासोदयात् ॥ तत्र षष्ठ्युपात्तार्थे तदिच्छारोपः । अयमर्थोऽर्थान्तरमाकाङ्क्षत इति व्यवहारात् । अपरस्त्वाकाङ्क्षाविषयत्वात्साकाङ्क्ष इति बोध्यम् ॥ **दानादीति** । दानं वेतनादेः ॥ **स्वाम्यमि**त्यस्य 'पुरुषे' इति शेषः ॥ भाष्ये—**षष्ठी वाचिकेति** । समासे त्वाकाङ्क्षावशादेव तद्बोधो वाक्यतुल्याकाङ्क्षाया एवात्र सत्त्वाद् । विरुद्धविभक्तिराहित्येपि भेदसंबन्धबोध इति भावः ॥ विशेषणविशेष्यभावांशे वाक्यन्यायेन समासस्यापि शक्तिः, न तु सा विशिष्टोपस्थितिनियामिकेति वा बोध्यम् ॥ आकाङ्क्षयापि राजार्थपुरुषार्थयोः संबन्धे इदं शक्तमिति शक्तिग्रहाद् न विशिष्टोपस्थितिरत्र पक्षे । अयमपि वृत्तिवर्तनवाद्येकदेशिन एव पक्षो न तु नित्यशब्दवादिन इति बोध्यम् ॥ वाक्ये त्वाकाङ्क्षितस्यास्य विभक्तिशब्दवाच्यत्वम् । न च संबन्धसंबन्धो वाक्येप्याकाङ्क्षालभ्योऽनवस्थापत्तेरिति दिक् ॥ भाष्ये—**क्रियाकारकयोरभिसंबन्धस्येति** । शक्तिः संबन्धश्चोभयमपि विभक्तिशक्यं घटमित्येतन्मात्रादपि घटकर्मिकेति बोधात्संबन्धस्य

वाक्यार्थत्वासंभवात् । अत एव घटमित्युक्ते क्रियाविशेषाकाङ्क्षेति भावः ॥ शक्तिरेवाभिसंबन्ध इति । इदं चिन्त्यम् । षष्ठ्यामित्रापि संबन्धबोधकताया एव भाष्याभिप्रेतत्वस्य तदक्षरस्वारस्येन लाभात् लक्षणायां मानाभावाच्च । भाष्यान्तरस्यैतद्विरुद्धस्यानुपलम्भाच्च ॥ अथ वेतीत्यपि न, कारकशब्देन शक्तेरुक्तौ क्रियाकारकशक्त्योरभिसंबन्धस्येत्यर्थलाभेपि भाष्यतः शक्तेर्वाच्यत्वालाभात् । नापि शक्तिसंबन्धस्य द्वितीया वाचिकेति यत्किंचिदेतत् ॥

(आक्षेपभाष्यम्)

अथ यद्येवैकार्थीभावः सामर्थ्यम्.अथापि व्यपेक्षा सामर्थ्यम् । किं गतमेतदियता सूत्रेण, आहोस्विदन्यतरस्मिन्पक्षे भूयः सूत्रं कर्तव्यम् ? ॥

(प्रदीपः) **अथ यद्येवेति** । यद्यस्मात् सूत्राद् द्विविधस्यापि सामर्थ्यस्य संप्रत्ययः तदा युक्तायुक्तविचारणा युक्ता नान्यथेति प्रश्नः ॥

(उद्द्योतः) भाष्ये—**अथ यद्येवेति** । ननु पूर्वं परार्थाभिधानमपि सामर्थ्यमुक्तं भेदसंसर्गादि च तत्कथमधुनैकार्थीभावव्यपेक्षयोरेवोल्लेख इति चेत् । न, तेषामेकार्थीभावपदार्थत्वादिति तात्पर्यात्॥

(समाधानभाष्यम्)

गतमित्याह ॥ कथम् ? । समोयमर्थशब्देन सह समासः । सम् चोपसर्गः । उपसर्गाश्च पुनरेवमात्मकाः—'यत्र कश्चित् क्रियावाची शब्दः प्रयुज्यते तत्र क्रियाविशेषमाहुः' । न चेह कश्चित् क्रियावाची शब्दः प्रयुज्यते, येन समः सामर्थ्यं स्यात् । तत्र प्रयोगादेतद्गन्तव्यम्—'नूनमत्र कश्चित् प्रयोगार्हः शब्दो न प्रयुज्यते येन समः सामर्थ्यम्' इति । तद्यथा-धूमं दृष्ट्वा-'अग्निरत्र' इति गम्यते, त्रिविष्टब्धकं दृष्ट्वा 'परिव्राजक' इति ॥ कः पुनरसौ प्रयोगार्हः शब्दो न प्रयुज्यते ? ॥ [उच्यते] सङ्गतार्थं समर्थं संसृष्टार्थं समर्थं संप्रेक्षितार्थं समर्थं संबद्धार्थं समर्थमिति ॥ तद्यदा तावदेकार्थीभावः सामर्थ्यम्, तदैवं विग्रहः करिष्यते—सङ्गतार्थः समर्थः, संसृष्टार्थः समर्थ इति । तद्यथा—'सङ्गतं घृतं सङ्गतं तैलम्' इत्युच्यते, एकीभूतमिति गम्यते । संसृष्टार्थः समर्थ इति । तद्यथा—'संसृष्टोग्निः' इत्युच्यते, एकीभूत इति गम्यते ॥

यदा व्यपेक्षा सामर्थ्यम्, तदैवं विग्रहः करिष्यते—संप्रेक्षितार्थः समर्थः संबद्धार्थः समर्थ इति ॥ कः पुनरिह संबध्नात्यर्थः ? ॥ व्यतिषक्तः ॥ संबद्ध इत्युच्यते यो रज्ज्वा अयसा वा कीलेन वा व्यतिषक्तो भवति ॥ नावश्यं बध्नातिर्व्यतिषङ्ग एव वर्तते । किं तर्हि ? । अहानावपि वर्तते । तद्यथा—'संबद्धाविमौ दम्पती' इत्युच्यते यावन्योन्यं न जहीतः ॥ अथ वा भवति चैवंजातीयकेषु बध्नातिर्वर्तते । तद्यथा 'अस्ति नो गर्गैः संबन्धः' 'अस्ति नो वत्सैः संबन्धः' इति ॥

(प्रदीपः) **सं चोपसर्ग इति** । तेन तस्य द्रव्यवाचिनाऽर्थशब्देन सामर्थ्यं नोपपद्यत इति संशब्दोपादानायोग्या क्रियाक्षिप्यते इत्यर्थः ॥ **सङ्गतार्थं संसृष्टार्थमिति** तुल्यार्थधातुनिर्देशः । **संप्रेक्षितार्थं संबद्धार्थ**मिति पर्यायनिर्देशः ॥ **व्यतिषक्त इति** । रज्ज्वादिनिमित्तः संश्लेषो व्यतिषङ्गः ॥ **एवंजातीयकेष्विति** । व्यपेक्षायुक्तेष्वित्यर्थः ॥ **अस्ति न इति** । सत्यामपि हानौ विद्यादिकृतापेक्षायां संबन्धशब्दस्य दर्शनादित्यर्थः ॥

(उद्द्योतः) **संचोपसर्ग इति** । यद्यप्यनुपसर्गा अपि प्रादयः सन्ति तथापि प्रसिद्धत्वादेवमुक्तम् ॥ **क्रियाविशेषम्** । क्रियागतं विशेषम् ॥ **येन सम इति** । यदर्थेन समोर्थस्य सामर्थ्यमित्यर्थः । तस्मात्तदर्थान्तर्भावोऽत्रानुमीयते इति भावः । इयमेव शाकपार्थिवादौ गतिः ॥ ननु प्रक्रान्तार्थद्वयावगमकत्वे पृष्टेऽर्थचतुष्टयकथनमनुपयोगीत्यत आह—**तुल्यार्थेति** ॥ ननु गमिसृज्योरिवेक्षतिबध्नात्योस्तुल्यार्थत्वं न दृष्टमत आह—**पर्यायेति** । पूर्वत्र तुल्यार्थधातुनिर्देशद्वारा पर्यायत्वम्, इह तु धात्वोस्तुल्यार्थत्वाभावेपि समुदाययोः पर्यायत्वमित्यर्थः ॥ पर्यायोपादानं च तदर्थदार्ढ्याय ॥ परस्परसंसृष्टार्थोपस्थितिरेव, न पृथगुपस्थितिरित्येकार्थीभावपदार्थः स्पष्टमेवानेनोक्तः ॥ व्यतिषक्तोत्र न कर्मव्यतिहार इत्याह—**रज्ज्वादीति** ॥ भाष्ये—**अहानाविति** । अहानिः परस्परं विना शाब्दबोधाजनकमेवेति बोध्यम् । अन्तरङ्गाकाङ्क्षावशादिति तात्पर्यम् । यथा च वत्सयोस्तयोरन्यासंबन्धस्तथाऽनयोर्विशेषणसंबन्धो विशेषणसजातीयविशेषणसंबन्धश्च नेति सूचितम् ॥ ननु संबद्धाविमाविल्यत्रैकोपस्थितिविषयत्वमेव संबद्धत्वम्, न चैवं प्रकृते । भिन्नोपस्थितिविषयत्वं हि व्यपेक्षा । तत्र तु हानिरस्त्येवेत्यत आह—**अथ वा भवति चैवमिति** ॥ तद्याचष्टे—**सत्यामपि हानाविति** । भिन्नोपस्थितिविषयत्वे इत्यर्थः ॥

(सामर्थ्यदूषणाधिकरणम्)

(व्यपेक्षादूषणभाष्यम्)

अथैतस्मिन्व्यपेक्षायां सामर्थ्ये योसावेकार्थीभावकृतो विशेषः स वक्तव्यः ॥

(प्रदीपः) **अथैतस्मिन्निति** । यदि वृत्तावेकार्थीभावो नाभ्युपगम्यते तदा वाक्यवत् संख्याविशेषोपसर्जनविशेषणादीनां प्रसङ्गात्तदभावो वचनेन प्रतिपाद्यो वावचनं च कर्तव्यं

समानार्थस्य वाक्यस्यानिवृत्त्यर्थम् । तदेवं शब्दस्य स्वाभाविकं रूपं कदाचिन्नित्यदर्शनाश्रयणेनानुगम्यते कदाचिदबुधबोधनार्थं कार्यदर्शनाश्रयणेन ॥ कार्यपक्षे तु बहवो वार्ता धर्मा वचनेन प्रतिपाद्या इति गौरवप्रसङ्गः । तथा हि—निष्कौशाम्बिर्गोरथो घृतघटो गुडधानाः केशचूडः सुवर्णालङ्कारो द्विदशाः सप्तपर्णो गौरखर इत्यादिषु क्रान्तयुक्तपूर्णमिश्रसंघातविकारसुच्प्रत्ययलोपो वीप्साजातिविशेषाभिधायित्वं च वचनप्रतिपाद्यम् ॥ नित्यदर्शने त्वेकार्थीभावकृत एवायं विशेष इति न किंचित् प्रतिपादनीयम् ॥

(उद्द्योतः) एवमुभयोः मतारूढत्वं कृत्वा व्यपेक्षापक्षं दूषयति—भाष्ये—**अथैतस्मिन्निति** ॥ **संख्याविशेषेति** । अश्वमुचर इत्यादौ ॥ **वचनेनेति** । **सविशेषणानां वृत्तिर्नेत्यादिना** ॥ ननु विभाषाधिकारादाचार्यस्यायमेव पक्षोऽभिप्रेतो लक्ष्यतेऽत आह—**तदेवमिति** ॥ क्रान्तादिलोपाविधानं नित्यताश्रयेण । विभाषाधिकारश्च कार्यशब्दाश्रयेण तत्पक्षेऽर्थस्यापि शास्त्रैकगम्यत्वेनैकार्थीभावस्य वैकल्पिकत्वं बोधयितुं सूत्रमावश्यकमिति भावः ॥ **कार्यपक्षे तु बहवो वार्ता धर्मा इति** । वाक्याद्वृत्तिर्निष्पद्यते इति वादिनां वाक्यश्रूयमाणक्रान्तादीनां शास्त्रं विना लोपासंभवो वीप्सादिबोधासंभवश्चेति भावः ॥ **नित्यदर्शने त्विति** । एकार्थीभाववादिनाऽर्थानां स्वाभाविकत्वपक्षस्यैव प्रागुपपादनान्नित्यदर्शनशब्देनैकार्थीभावदर्शनमत्रोच्यते इत्याहुः ॥ वस्तुतस्तु निरादिपूर्वपदानां क्रान्ताद्यर्थवृत्तित्वैषामर्थानां नैकार्थीभावकृतविशेषत्वम् । अत एव तत्कृतविशेषेषु भाष्ये नैतेषामुक्तिः । **निरादयः क्रान्ताद्यर्थे** इत्यादीनां क्रान्ताद्यर्थे वर्त्तमाना निरादय इत्यर्थः । एवं चोक्तार्थानामिति न्यायेन तेषामन्यपदार्थबोधकपदवदप्रयोगः सिद्धः । अत एव **संख्ययाव्ययेति** सूत्रे समासेनाभिहितत्वात्सुजर्थस्य सुचोऽभाव इति भाष्य उक्तम् सुजर्थश्च जन्मेति तत्रैव वक्ष्यते ॥ किं **चैकार्थीभावो** नामैकोपस्थितिस्तत्कृतत्वं न क्रान्तादिलोपस्य, संख्याविशेषप्रतीतौ हि पृथगुपस्थापकपदज्ञानं कारणमिति तत्प्रतीत्यभावस्तत्कृतो भवत्येव । अन्यथा घटः घटपटावित्यादौ घटत्वादेरपि संख्यावत्त्वेनोपस्थित्यापत्तिः । एवं द्वन्द्वे चकाराप्रयोगोऽप्येतत्कृत एव । न च समासेन चार्थस्याभिहितत्वात्तदप्रयोगः, समासेन सत्त्वभूतस्य विशेष्यतयाऽभिधानेऽप्यसत्त्वभूतस्य विशेषणतया बोधार्थं चप्रयोगस्य दुर्वारत्वात् । पृथगुपस्थितयोरेव समुच्चयस्य च्चद्योत्यत्वेन तदप्रयोग इति तस्यापि तत्कृतत्वम् । लोकेऽपि पृथग्ज्ञातयोरेवैकदेशत्वे समूहादिव्यवहारात् । चार्थे द्वन्द्व इति तु सादृश्याच्चार्थत्वारोपेण नेयमिति दिक् ॥

(११९५ दूषणदर्शकवार्तिकम् ॥ ६ ॥)

॥ * ॥ तत्र नानाकारकान्निघातयुष्मदस्मदादेशप्रतिषेधः ॥ * ॥

(भाष्यम्) **तत्रैतस्मिन् व्यपेक्षायां सामर्थ्ये सति नानाकारकान्निघातयुष्मदस्मदादेशाः प्राप्नुवन्ति तेषां प्रतिषेधो वक्तव्यः ॥**

निघात—अयं दण्डो हरानेन । अस्ति दण्डस्य हरतेश्च व्यपेक्षेति कृत्वा निघातः प्राप्नोति ॥

युष्मदस्मदादेशाः—ओदनं पच तव भविष्यति । ओदनं पच मम भविष्यति । अस्त्योदनस्य युष्मदस्मदोश्च व्यपेक्षेति कृत्वा वान्नावादयः प्राप्नुवन्ति ॥

तेषां प्रतिषेधो वक्तव्यः ॥

(प्रदीपः) एवं व्यपेक्षासामर्थ्ये दोषमभिधायेदानीं ये सर्वथा दोषास्तानुदाहरति—**तत्र नानाकारकादिति** । नानाशब्दः पृथग्भाववचनः । तेन भिन्नायाः क्रियायाः यत्कारकं तन्नानाकारकम् । यथा—अयं दण्डो हरानेनेति दण्डोऽस्तिक्रियायाः कर्ता, न तु हरतिक्रियायाः ॥ तथा नाना भिन्नमन्यत्कारकं यस्य तदपि नानाकारकम् । यथा—ओदनं पच तव भविष्यतीत्यत्र पचेस्तवेत्येतत्कारकत्वेन नोपात्तम् ततः पचेत्येतस्मादुत्तरस्य युष्मदादेशो न भवति । क्वचित्तु पचौदनं तव भविष्यतीति पाठः । ओदनस्य पचतिक्रियां प्रति कारकत्वम् न तु भवतिक्रियां प्रतीति नानाकारकत्वं भिन्नक्रियापेक्षत्वात्कारकत्वस्य ॥ **अस्ति दण्डस्येति** । अनेनेति पदेन दण्डस्य हरणे करणत्वेन निर्देशात् ॥ **अस्त्योदनस्येति** । स्वस्वामिभावस्य भाविनः प्रतिपादनादित्यर्थः ॥

(उद्द्योतः) ननु व्यपेक्षावादे एकार्थीभावकृतविशेषस्य वक्तव्यत्ववदेकार्थीभाववादेऽपि निघातयुष्मदस्मदाद्यादेशोदाहरणविषयैकार्थीभावाभावेन **समर्थ**परिभाषानुपस्थितौ तिष्ठति देवदत्तो गच्छ त्वमित्यादौ भिन्नवाक्ये निघातादिप्रतिषेधो वक्तव्यः स्यात् । व्यपेक्षावादे तु न दोषस्तत्रापि **समर्थ**परिभाषोपस्थितौ भिन्नवाक्ये सामर्थ्याभावात् ॥ एवं राज्ञो गौश्चाश्वश्च पुरुषश्चेत्यर्थे राज्ञो गवाश्वपुरुषाभ्यामेकार्थीभावस्य वक्तुं शक्यतया युगपत्षष्ठीतत्पुरुषद्वन्द्वौ प्राप्नुतस्तथा च स्वरद्वयं स्यादिति तत्प्रतिषेधो वाच्यः । व्यपेक्षावादे तु न, राजन्शब्देनैव व्यपेक्षा न गवेति वक्तुं शक्यत्वादिति पूर्वपक्षे व्यपेक्षावादेऽपीदमवश्यं वाच्यमित्याह—भाष्ये—**तत्र नानाकारकादिति** । **तत्र** पक्षद्वयेऽपि ॥ इदमेवाभिप्रेत्य व्याचष्टे—**ये सर्वथा दोषास्तानुदाहरतीति** । **सर्वथा** पक्षद्वयेऽपीत्यर्थः । भाष्ये तत्र चेति पाठे **तत्रैकार्थीभावे** । **च**व्यपेक्षायाम् ॥ **तत्रैतस्मिन् व्यपेक्षायामिति** । **तत्रै**कार्थीभावे ॥ **एतस्मिन्** व्यपेक्षासामर्थ्ये चेत्यर्थः ॥ हरतेर्नानाप्रकारानेककारकापरत्वाभावादाह—**नानाशब्द इति** । **पृथग्भावेति** । पृथक्क्रियावचन इत्यर्थः ॥ भावशब्दः क्रियापरः तदाह—**भिन्नायाः क्रियाया इति** । निघातप्राप्तिविषयभिन्नाया इत्यर्थः ॥ अयं दण्ड इत्यत्र निघातविषया हरणक्रिया तद्भिन्नास्तिक्रिया तत्कारकं दण्डः ॥ अत्र पक्षे ओदनं पचेत्यादेरनुदाहरणत्वमाशङ्क्याह—**तथा नानेति** । अन्यद् युष्मदस्मद्भिन्नं कारकं यस्य पचेत्यादिरित्यर्थः ॥ प्रतिषेधवचनारम्भे तत्रादेशाभावमुपपादयति—**अत्र पचेरिति** ॥ **क्वचित्त्विति** । युष्म-

दसत्साध्यभवनक्रियाभिन्नपच्यादिक्रियाकारकत्वादोदनादि नानाकारकमिति भावः ॥ ननु हरतेः कारणमात्रापेक्षत्वेन न दण्डेन व्यपेक्षेत्यत्राह—अनेनेतिपदेनेति । अत एवास्ति सर्पिष्पिवानेन पय इत्यादौ षत्वम् ॥ पचौदनमित्यत्र संबन्धाभावात्कथं व्यपेक्षेत्यत आह—भाविन इति ॥ ओदनं पचेति पाठेप्योदनद्वारिका पचिनापि व्यपेक्षेति बोध्यम् । अर्थयोराकाङ्क्षैव व्यपेक्षेति तात्पर्यम् ॥

(आक्षेपभाष्यम्)

किमुच्यते—नानाकारकादिति, यदा तेनैवासज्य ह्रियते ॥

(प्रदीपः) **तेनैवासज्येति** । ततश्च दण्डस्य हरणं प्रति कारकत्वान्नास्ति नानाकारकत्वमिति प्रश्नः ॥

(समाधानभाष्यम्)

नापि ब्रूमः—अन्येनासज्य ह्रियत इति ॥ किं तर्हि? । शब्दप्रमाणका वयम् । यच्छब्द आह, तदस्माकं प्रमाणम् । शब्दश्चेह सत्तामाह—'अयं दण्डः' अस्तीति गम्यते । स दण्डः कर्ता भूत्वान्येन शब्देनाभिसंबध्यमानः करणं संपद्यते । तद्यथा—कश्चित्कंचित्पृच्छति—'क देवदत्तः' इति । स तस्मायाचष्टे—'असौ वृक्षे' [इति 'कतरस्मिन्'] 'यस्तिष्ठति' इति स वृक्षोधिकरणं भूत्वाऽन्येन शब्देनाभिसंबध्यमानः कर्ता संपद्यते ॥

(प्रदीपः) **अयं दण्डोस्तीति** । यत्रान्यत् क्रियापदं न श्रूयते तत्रान्तरङ्गत्वादस्तिक्रियैव प्रतीयते । ततोस्तिक्रियायां दण्डस्य कर्तृत्वाद्भवत्येव नानाकारकत्वमित्यर्थः ॥ **क देवदत्त इति** । यदा बहवः पुरुषा दूरस्था भवन्ति तदैते प्रश्नोत्तरे ॥ **यस्तिष्ठतीति** । यदान्ये निपातिता वृक्षाः, एकस्तूर्ध्वस्तदा विशिष्टवृक्षाधिकरणत्वेन देवदत्तः प्रतिपाद्यते ॥

(उद्द्योतः) **एकस्तूर्ध्व इति** । तिष्ठतेश्चोर्ध्वदेशसंयोगोप्यर्थ इति भावः ॥

(११९६ दूषणान्तरवार्तिकम् ॥ ७ ॥)

॥ * ॥ प्रचये समासप्रतिषेधः ॥ * ॥

(भाष्यम्) **प्रचये समासप्रतिषेधो वक्तव्यः । राज्ञो गौश्चाऽश्वश्च पुरुषश्च राजगवाश्वपुरुषा इति ॥**

(प्रदीपः) **प्रचय इति** । अनेकस्मिन् संबन्धिनि विवक्षित इत्यर्थः । तत्र गो राज्ञापि सामर्थ्यमश्वपुरुषाभ्यामपि । तत्र युगपद् द्वौ द्वन्द्वतत्पुरुषौ प्राप्नुतः । पूर्वं वा तत्पुरुषः पश्चाद् द्वन्द्वः । विप्रतिषेधाभावाच्च न परत्वेन व्यवस्था भिन्नसमुदायविषयत्वात् संज्ञाद्वयस्य । तत्र षष्ठीतत्पुरुषे सति **गोरतद्धितलुकीति** टच् प्राप्नोति । अर्थश्च भिद्यते राजगवाश्वपुरुषा इत्युच्यमानेऽश्वपुरुषयो राज्ञा संबन्धो न प्रतीयेत ॥

(उद्द्योतः) भाष्ये—**प्रचयेति** । व्यपेक्षावादेपि समुदायेन व्यपेक्षायामवयवातिरिक्तसमुदायस्यावयवानालिङ्गितस्य निरूपयितुमशक्यत्वेनावयवैरपि व्यपेक्षास्त्येवेति तन्मतेऽप्ययं दोषस्तदवस्थ इति भावः ॥ ननु प्रचयशब्दस्य समाहारपर्यायत्वेन समाहारे समासनिषेधेपीतरेतरयोगे स दुर्वार इत्यत आह—**अनेकस्मिन्निति** । प्रचय आधिक्यमिति भावः ॥ ननु युगपदेकस्यानेकसंबन्धानुपपत्तेः कथं युगपत्समासद्वयप्रसङ्गोऽत आह—**तत्रेति** ॥ **गो राज्ञापीति** । समुदायव्यपेक्षायामवयवव्यपेक्षायाः समुदायैकार्थीभावेऽवयवैकार्थीभावस्य च दुर्निवारत्वादिति भावः । अश्वादिभिश्च साहित्यसत्त्वादेव स इति बोध्यम् ॥ **पूर्वं वा तत्पुरुष इति** । प्रथमातिक्रमे कारणाभावादिति भावः ॥ ननु परत्वाद् द्वन्द्व एव भविष्यतीति न दोषोऽत आह—**विप्रतिषेधेति** ॥ भाकडारीयत्वेप्यविरोधमुपपादयति—**भिन्नसमुदायेति** ॥ **टजिति** । तथा च स्त्रीत्वे ङीप् स्यात् । किं च द्वन्द्वोत्तरतत्पुरुषेऽवङो वैकल्पिकत्वेन राजगोश्वपुरुषा इत्यपीष्यते तन्न स्यादिति भावः ॥

(११९७ द्वितीयदूषणबाधकवार्तिकम् ॥ ८ ॥)

॥ * ॥ समर्थतराणां वा ॥ * ॥

(व्याख्याभाष्यम्)

समर्थतराणां वा पदानां समासो भविष्यति ॥ कानि पुनः समर्थतराणि? । यानि द्वन्द्वभावीनि ॥ कुत एतत्? । एषां ह्याशुतरा वृत्तिः प्राप्नोति । तद्यथा—'समर्थतरोयं माणवकोऽध्ययनाय' इत्युच्यते 'आशुतरग्रन्थः' इति गम्यते ॥

(प्रदीपः) **समर्थतराणां वेति** । शक्ततराणामित्यर्थः ॥ **एषां ह्याशुतरेति** । प्रथमा प्रातिपदिकार्थमात्रे विधीयमाना न किंचिद्बाह्यं वस्तु अपेक्षते षष्ठी तु बाह्यसंबन्ध्यपेक्षत्वाद्बहिरङ्गा । तत्रान्तरङ्गप्रथमानिमित्तः पूर्वं द्वन्द्वो भवति । **असिद्धं बहिरङ्गमन्तरङ्गे** इति द्वन्द्वे कर्तव्ये षष्ठीसमासस्यासिद्धत्वात् ॥ **आशुतरग्रन्थ इति** । आशु प्रतिपत्तव्यो ग्रन्थः आशुतर उच्यते ॥

(उद्द्योतः) **समर्थतराणामिति** भाष्यं नैकार्थीभावपरं तत्र तरतमायोगादत आह—**शक्तेति** ॥ समर्थतरत्वे आशुतरत्वं हेतुः, तत्त्वमन्तरङ्गत्वादिति व्युत्पादयति—**प्रथमेत्यादिना** ॥ **आशुतरग्रन्थ इति** बहुव्रीहिः । एवं चाशुतरं कार्यप्राप्तिमत्त्वमेव शक्ततरत्वं बोध्यम् ॥

(व्याख्यान्तरभाष्यम्)

अपर आह—समर्थतराणां वा पदानां समासो भविष्यति ॥ कानि पुनः समर्थतराणि? । यानि द्वन्द्वभावीनि । कुत एतत्? । समानविभक्तीन्येतानि, अन्यविभक्ती राजा । भवति विशेषः स्वस्मिन् भ्रातरि पितृव्यपुत्रे च ॥

(प्रदीपः) **एतानीति** । तुल्यजातीयत्वं व्यपेक्षायामेकार्थीभावे च प्रत्यासन्नतरं कारणमित्यर्थः ॥

(उद्द्योतः) तुल्यैति। तुल्यजातीयैः प्रथमं झटित्येकार्थीभावस्य व्यपेक्षाया वा कल्पनात्पूर्वं द्वन्द्वे ततः षष्ठीतत्पुरुष इत्यर्थः॥

(११९८ द्वितीयदूषणबाधकवार्तिकान्तरम्॥ ९॥)

॥*॥ समुदायसामर्थ्याद्वा सिद्धम्॥*॥

(व्याख्याभाष्यम्)

समुदायसामर्थ्याद्वा पुनः सिद्धमेतत्। समुदायेन राज्ञः सामर्थ्यं भवति, नावयवेन॥

(प्रदीपः) **समुदायसामर्थ्यादिति।** समुदायद्वन्द्वार्थं प्रति राजा विशेषणत्वेनोपात्त इति तेनैव राज्ञः सामर्थ्यं नावयवेनेत्यर्थः॥

(उद्द्योतः) **नावयवेनेति।** प्रत्येकमवयवैरनुमीयमानस्य सामर्थ्यस्य सत्त्वेपि साक्षान्नेत्यर्थः॥ एवं च तस्य समुदायेन सामर्थ्यात् पूर्वं तत्समुदायप्रयुक्तो द्वन्द्व इति भावः॥ ननु द्वन्द्वे समुदायेनेव तदवयवगोशब्देनापि राजपदार्थस्य सामर्थ्यसत्त्वात्समुदायस्यापि षष्ठीतत्पुरुषसंज्ञा स्यादिति टच्प्रसङ्ग इति चेन्न। नावयवेनेत्यस्याश्वपुरुषसापेक्षेणेति शेषेणादोषात्।

(व्याख्यान्तरभाष्यम्)

अपर आह—

(व्याख्यान्तराय न्यासान्तरम्)

समर्थतराणां वा समुदायसामर्थ्यात्॥

(व्याख्याभाष्यम्)

समर्थतराणां वा पदानां समासो भविष्यति॥ कुत एतत्?। समुदायसामर्थ्यादेव॥

(प्रदीपः) **अपर आहेति।** अत्र पक्षे समुदायसामर्थ्यं समर्थतरत्वे हेतुः। समुदायसंबन्धे चावयवस्याप्यनुमीयमानः संबन्धोऽस्तीति तदपेक्षः प्रकर्षप्रत्ययः॥

(उद्द्योतः) तदेव स्फुटं व्याख्यानान्तरव्याजेनाह—**अपर आहेति**॥ राज्ञः समुदायेनैव सामर्थ्यात्तरपो वैयर्थ्यमाशङ्क्याह—**समुदायेति**॥

(आक्षेपभाष्यम्)

अस्मिन्पक्षे 'वा' इत्येतदसमर्थितं भवति॥

(प्रदीपः) **अस्मिन् पक्षइति।** एकस्मिन् साध्ये हेतुद्वयोपादाने विकल्पो भवति इह त्वन्यत्रान्यो हेतुः॥

(समाधानभाष्यम्)

एतच्च समर्थितम्॥ कथम्?। नैव वा पुनरत्र राज्ञोऽश्वपुरुषावपेक्षमाणस्य गवा सह समासो भवति॥ कथं तर्हि गोः राजानमपेक्षमाणस्याश्वपुरुषाभ्यां सह समासो भवति?॥ प्रधानमत्र तदा गौर्भवति। भवति च प्रधानस्य सापेक्षस्यापि समासः॥

(प्रदीपः) **एतच्चेति।** सापेक्षत्वेनासामर्थ्याद् राज्ञो गवा समासो न भवतीत्यस्यार्थस्य वाशब्दः प्रतिपादकः॥

(उद्द्योतः) **इत्यस्यार्थस्येति।** विशेषणसापेक्षत्वे इव विशेष्यान्तरसापेक्षत्वमप्यसामर्थ्यप्रयोजकम्। एवं चेदं पक्षद्वयेप्यनावश्यकमिति भावः॥ भाष्ये—**प्रधानमत्रेति।** अवयवसंख्यया तत्र समूहस्य संख्यावत्त्वाश्रयणात्तस्य प्राधान्यमिति भावः॥

(वाक्यलक्षणाधिकरणम्)

(११९९ वाक्यलक्षणवार्तिकम्॥ १०॥)

॥*॥ आख्यातं साव्ययकारकविशेषणं वाक्यम्॥*॥

(व्याख्याभाष्यम्)

आख्यातं साव्ययं सकारकं सकारकविशेषणं वाक्यसंज्ञं भवतीति वक्तव्यम्॥

साव्ययम्—उच्चैः पठति नीचैः पठतीति॥

सकारकम्—ओदनं पचति॥

सकारकविशेषणम्—ओदनं मृदु विशदं पचति॥

(प्रदीपः) **आख्यातमिति।** नानाकारकाभिघातादिनिवृत्तये क्वचित् प्रवृत्तये च समानवाक्ये निघातयुष्मदस्मदादेशा वक्ष्यन्ते। तत्र लौकिकवाक्यग्रहणनिषेधार्थं वाक्यं परिभाष्यते॥ अव्ययकारकविशेषणानि प्रत्येकं समुदितानि चाश्रीयन्ते यथा वृषलैर्न प्रवेष्टव्यम्। **अट्कुप्वाङ्नुम्व्यवायेपीति।** आख्यातमिति चैकत्वं विवक्ष्यते। लक्षणविधानसामर्थ्यात्। तथा च **तिङ्ङतिङ** इत्यत्र वक्ष्यते **तिङ्प्रतिषेधानर्थक्यं च समानवाक्याधिकारादिति।** भवतिपचतीत्यादौ सत्यपि साध्यसाधनभावे आख्यातयोर्द्वित्वात् समानवाक्यत्वाभावान्निघाताप्रसङ्गात्॥ **उच्चैरिति।** यद्यप्यव्ययं कारकं विशेषणं च तथापि प्रपञ्चार्थमस्योपादानम्। तथा च वक्ष्यते—**आख्यातं सविशेषणमित्येवेति**॥

(उद्द्योतः) वाक्यलक्षणकरणस्यासंगतिमाशङ्क्याह—**नानेति॥ क्वचिदिति।** नद्यास्तिष्ठति कूले इत्यादौ॥ अत्र ह्यसामर्थ्यान्न प्राप्नोति यथा कथंचित्सामर्थ्यग्रहणे तु—अयं दण्डो हरानेनेत्यादावपि स्यादिति भावः॥ **लौकिकेति।** सुप्तिङन्तचयो वाक्यमित्यादि॥ **लक्षणविधानेति।** निष्क्रियवाक्याभावस्य लोकव्युत्पत्तिसिद्धत्वादिति भावः॥ अव्ययग्रहणवैयर्थ्यमाशङ्कते—**यद्यप्यव्ययमिति।** स्वर्गं गच्छतीत्यादौ कारकम्। उच्चैः पठतीत्यत्र विशेषणं क्रियाविशेषणत्वादत्रापि कर्मत्वं वा॥

(१२०० वाक्यलक्षणवार्तिकम्॥ ११॥)

॥*॥ सक्रियाविशेषणं च॥*॥

(व्याख्याभाष्यम्)

सक्रियाविशेषणं चेति वक्तव्यम्। सुष्ठु पचति दुष्ठु पचतीति॥

(प्रदीपः) **सक्रियाविशेषणं चेति** । प्रत्यासत्त्या कारकस्यैव यद्विशेषणं तद् गृह्यते, न तु क्रियाया इति भावः ॥ आख्यातेन च क्रियाप्रधानत्वं लक्ष्यत इत्यतिङन्तेष्वपि देवदत्तेन शयितव्यमित्यादिषु वाक्यत्वं सिद्ध्यति ॥

(उद्द्योतः) सविशेषणमित्येव क्रियाविशेषणेपि सिध्यतीत्यत आह—**प्रत्यासत्त्येति** । यद्यपि कारकत्वादप्यस्य सिध्यति तथाप्यव्ययग्रहणवदिदमपि प्रपञ्चार्थमिति तत्त्वमिति बोध्यम् ॥ **क्रियाप्रधानत्वमिति** । लक्ष्यतावच्छेदकप्रदर्शनमिदम् । देवदत्तो गत इत्यादौ त्वस्तीत्यध्याहार्यमिति भावः ॥

(वाक्यलक्षणन्यासान्तरभाष्यम्)

अपर आह—"आख्यातं सविशेषणम्" इत्येव । सर्वाणि ह्येतानि विशेषणानि ॥

(१२०१ वाक्यलक्षणान्तरवार्तिकम् ॥ १२ ॥)

॥ * ॥ एकतिङ् ॥ * ॥

(व्याख्याभाष्यम्)

एकतिङ् वाक्यसंज्ञं भवतीति वक्तव्यम् । ब्रूहि ब्रूहि ॥

(प्रदीपः) **एकतिङिति** । एकशब्दः समानवचनो, न तु संख्यावाची । बहुव्रीहिश्चायम् ॥ **ब्रूहिब्रूहीति** । ब्रूहि ब्रूहि देवदत्तेत्यत्र वाक्यत्वादामन्त्रितनिघातः सिद्ध्यति ॥

(उद्द्योतः) नन्वेकग्रहणात्पुनरप्यनुपपत्तिस्तदवस्थैवेत्यत आह—**एकशब्द इति** ॥ एकस्य पदस्य वाक्यसंज्ञायां प्रयोजनाभावादाह—**बहुव्रीहिरिति** । एकं तिङन्तं यत्र समुदाये इत्यर्थः ॥ परेस्त्वाख्यातं सविशेषणं वाक्यमिति लक्षणं **तिङ्ङतिङः** इति सूत्रेऽतिङ्ग्रहणं कुर्वतः सूत्रकारस्याभिमतं लौकिकमेव पचतिभवतीत्येतत्साधारणम् । तत्र सविशेषणत्वेन विभागे साकाङ्क्षत्वं लब्धम् । तत्राख्यातपदेन क्रियाप्रधानं लक्ष्यते । तेन त्वया शयितव्यमित्यादेः संग्रहः । **सविशेषण**मित्यस्य साक्षात्परम्परया वा यद्विशेषणं तत्सहितमित्यर्थः । तेन नद्यास्तिष्ठति कूले इत्यादौ नद्या इत्यादेः समानवाक्यस्थत्वसिद्धिः । एतदेवाभिप्रेत्यामरकोशे कारकान्वितक्रियावाचकं सुबन्तचयतिङन्तचयसुप्तिङन्तचयान्यतमं वाक्यमित्युक्तम्—

सुप्तिङन्तचयो वाक्यं क्रिया वा कारकान्विता-

इत्यनेन । तत्र वाशब्दश्चेदर्थे । कारकं च तिङन्तवाच्यं तदतिरिक्तपदवाच्यं वेत्यन्यत् । एकस्य तत्त्ववारणाय **सुबन्तचये**त्यादि । एतत्समानार्थकमेवाख्यातमित्यादीति स्पष्टमेव । एतदेवैकोद्देश्यकैकविधेयकत्वगर्भमेकवाक्यलक्षणं बोध्यम् । तदुक्तं हरिणा—

"साकाङ्क्षावयवं भेदे परानाकाङ्क्षशब्दकम् ।
क्रियाप्रधानं गुणवदेकार्थं वाक्यमुच्यते"

इति । वाक्यमित्यस्यैकं वाक्यमित्यर्थः ॥ **अर्थैक्यादेकं वाक्यं साकाङ्क्षं चेद्विभागे स्यादि**ति जैमिनिसूत्रात् । अत एवोद्देश्यानेकत्वे विधेयानेकत्वे च वाक्यभेद इति मीमांसकोद्घोषः ॥ यत्तु कैयटेनास्य पारिभाषिकत्वमुक्तं, तत्प्रमादात् ॥ यदप्याख्यातमित्यत्रैकत्वविवक्षां कृत्वा पचति भवतीत्यत्र वाक्यत्ववारणं तेन कृतम् । तदपि न, आख्यातत्वपर्याप्त्यधिकरणमेकमेवेति प्रागुक्तभाष्यरीत्यैकत्वविवक्षायाः फलाभावात् ॥ किंच **व्यक्तिपक्षे न ब्राह्मणं हन्यादित्यादावेकं ब्राह्मणमहत्वा कृती स्यादि**ति भाष्योक्तन्यायेनात्रैकत्वविवक्षायामेकस्यैवाख्यातस्य वाक्यत्वं बोधितं स्यान्नाख्यातान्तरस्येति दोषात् । किं चानयैकत्वविवक्षया समकक्षाख्यातद्वित्वे पचतिकरोति चेत्यादौ तद्वारणेपि विशेषणमादाय तद्वित्वे वारणमशक्यं सविशेषणे आख्याते एकत्वसत्त्वात् । अनेन च ब्रूहिब्रूहीत्यस्याप्यसंग्रहः । विशेषणानुपादानेन सविशेषणत्वाभावात् । वाक्यत्वफलं तु 'मया किंचिद्वक्तव्यम्' इति प्रश्नोत्तरे । अत्रानन्त्यस्यापि प्रश्नाख्यानेत्यनेन वाक्यस्य टेः प्लुतसिद्धिः । अतः स्वशास्त्रपरिभाषितं लक्षणमाह—**एकतिङिति** ॥ यत्तु कैयटेन ब्रूहिब्रूहीतिभाष्योदाहरणं देवदत्तेति शेषपूरणेन व्याख्यातम् । तन्न, पूर्वलक्षणेनैव सिद्धेः । द्विःप्रयोगस्य भाष्ये व्यर्थत्वापत्तेश्च ॥ एतेन पूर्वलक्षणे एकत्वाविवक्षाशङ्कावारणेनैकत्वविवक्षाबोधनार्थमिदं लक्षणान्तरमुक्तमित्यष्टमे कैयटोक्तमपास्तम् ॥ यद्यप्यग्नेऽग्ने इत्यादौ पूर्वरूपाय द्वित्वेऽवान्तरपदत्वमप्यस्ति । एवं च ब्रूहिब्रूहीत्यत्र कथमेकतिङ्त्वं तथाप्येकानुपूर्वीकतिङन्तसमुदायो वाक्यमित्यर्थः । बहुव्रीहिसमासात् । तेन पचतीत्येतन्मात्रस्य न वाक्यत्वम् ॥ एतल्लक्षणानुसारेणैवातिङ इति प्रत्याख्यातमित्यन्यत् ॥ अत एव भगवतै**कतिङ्वाक्य**मित्यत्र चशब्दो वाशब्दो वा नोक्तः, भिन्नविषयत्वात् । एकविषयत्वे हि सोऽवश्यं वक्तव्यः स्यात् । दृश्यते हि भगवतस्तथा शैली तस्मादाद्यलक्षणं **वाक्यस्य टेरि**त्येतच्छास्त्रलोकसाधारणम् । अत एव पच पश्य च देवदत्तेत्यादौ प्लुतो भवत्येव । एकतिङित्येतन्मात्रोक्तौ तत्रापीदमेवेति भ्रमः स्यात्तदर्थमिदम् ॥ **समानवाक्ये** इत्येतद्विषयं क्वचित् प्लुतविषयं चैकतिङिति । अत एव ब्रूहिब्रूहीत्युदाहरणसंगतिः । अत एव **तिङ्ङतिङः** इति सूत्रे भाष्ये—**समानवाक्याधिकारादतिङ्ग्रहणानर्थक्य**मिति वार्तिकव्याख्यावसरे **न च समानवाक्ये द्वे तिङन्ते स्त** इति उक्तम् । तेनैवैकतिङिति बहुव्रीहिरिति च सूचितम् ॥ स्पष्टश्चायमर्थोऽग्रेऽत्र भाष्येपीत्यनुपदमेव स्फुटीभविष्यतीत्याहुः ॥

(१२०२ वाक्यलक्षणप्रयोजनवार्तिकम् ॥ १३ ॥)

॥ * ॥ समानवाक्ये निघातयुष्मदस्मदादेशाः ॥ * ॥

(व्याख्याभाष्यम्)

समानवाक्य इति प्रकृत्य निघातयुष्मदस्मदादेशा वक्तव्याः ॥ किं प्रयोजनम् ? । नानावाक्येषु मा भूव-

निघातादय इति। अयं दण्डो हरानेन। ओदनं पच तव भविष्यति । ओदनं पच मम भविष्यति ॥

(उद्द्योतः) **समानवाक्ये इति** । समानशब्द एकपर्यायः । एवंविधलक्षणलक्षिते एकवाक्ये इत्यर्थः ॥

(१२०३ दूषणवार्तिकम् ॥ १४ ॥)

॥ * ॥ योगे प्रतिषेधश्चादिभिः ॥ * ॥

(व्याख्याभाष्यम्)

चादिभिर्योगे प्रतिषेधो वक्तव्यः । ग्रामस्तव च स्वं मम च स्वम् ॥

(उद्द्योतः) **चादिभिर्योगइति** । न चवाहेतिसूत्रे समानवाक्ये इत्यस्य संबन्धो नेत्यर्थ इति कश्चित् ॥ तन्न । **यथान्यास एव चादिभि**रित्युत्तरभाष्यासंगतेः । किं च तव मते भिन्नवाक्येपि निषेधप्रवृत्तिरप्यस्य फलं वाच्यम् । तत्रादेशप्राप्त्यभावेन निषेधस्यैव वैयर्थ्यात्। तस्माद्युष्मदाद्यादेशप्रतिषेध इत्येवार्थः ॥

(आक्षेपभाष्यम्)

किमर्थमिदमुच्यते । यथान्यास एव चादिभिर्योगे प्रतिषेध उच्यते? ॥

(उद्द्योतः) **किमर्थमिदमिति** । इदं प्रतिषेधवचनम**स्यात् साव्यये**त्यादिवाक्यलक्षणं च किमर्थमिति प्रश्नः ॥ अत एवोत्तरग्रन्थे **वाक्यसंज्ञे**त्युक्तिः संगच्छते ॥

(समाधानभाष्यम्)

इदमद्यापूर्वं क्रियते वाक्यसंज्ञा समानवाक्याधिकारश्च । तद् द्वेष्यं विजानीयात् सर्वमेतद्विकल्पत इति । तदाचार्यः सुहृद् भूत्वान्वाचष्टे चादिभिर्योगे यथान्यासमेव भवतीति । सा चावश्यं वाक्यसंज्ञा वक्तव्या समानवाक्याधिकारश्च वक्तव्यः ॥

(उद्द्योतः) **वाक्यसंज्ञेति । एकतिङ्**ित्येषा ॥ **तद्द्वेष्यमिति ।** इदमसमर्थेऽप्राप्तावपूर्वविधायकमिव चादियोगेपि तदपवादतयाऽपूर्वविधायकम्, न त्वधिकार इति भ्राम्येत्तद्भ्रमनिवारणायेदमन्वाख्यातमित्यर्थः । **न चवाहे**त्यारम्भसामर्थ्यान्नैवमित्यन्वाख्यानतात्पर्यम् । **एवमेकतिङि**ति वाक्यलक्षणस्यैवोक्तौ शास्त्रे सर्वत्र **वाक्यस्य टे**रित्यादावपीदमेव वाक्यलक्षणमिति भ्राम्येत्तं प्रतीदमपि वाक्यलक्षणं शास्त्र आश्रीयत इत्यन्वाख्यानायाद्यं लक्षणम् । **समानवाक्ये** इत्यत्रैकतिङित्येव उदाहरणेन चान्यत्राप्यस्याश्रयणं सूचितम् । **चादिभिर्योगे** इत्याद्यप्युपलक्षणम् । एतच्चेद**मद्यापूर्वं क्रियते वाक्यसंज्ञा समानवाक्याधिकारश्च तद्द्वेष्य**मित्यनेन सूचितम् । इदं यद् द्वयं क्रियते तद्द्वेष्यमित्यर्थस्य स्वरसतः प्रतीतेरित्यलम् ॥ **विकल्पत** इत्यस्य व्याप्नोतीत्यर्थः । एवं च **समानवाक्ये** इत्यधिकारपरमेकतिङित्येव चात्र वाक्यपदार्थः । आद्यलक्षणेनायं दण्डो हरानेनेत्यस्यापि वाक्यत्वात्तत्र निघातापत्तिः । अयं दण्डोऽस्तीत्यस्यापि अनेनेत्येतदर्थपरिच्छेदद्वारा हरतिक्रियाविशेषणत्वात् ॥ पचौदनं तव भविष्यतीत्यत्र हेतुहेतुमद्भावेनान्वयाद् भवनक्रियां प्रति तस्य विशेषणत्वाद्वाक्यत्वमिति भावः ॥ **साचावश्यमिति** । वाक्यसंज्ञाफलमयं दण्डो हरानेनेत्युक्तम् ॥

(१२०४ नियमफलवार्तिकम् ॥ १५ ॥)

॥ * ॥ समर्थनिघाते हि समानाधिकरणयुक्तयुक्तेषूपसंख्यानमसमर्थत्वात् ॥ * ॥

(व्याख्याभाष्यम्)

समर्थनिघाते हि सति समानाधिकरणयुक्तयुक्तेषूपसंख्यानं कर्तव्यं स्यात् ॥ समानाधिकरण—पटवे ते दास्यामि, मृदवे ते दास्यामि ॥ समानाधिकरण ॥ युक्तयुक्ते—नद्यास्तिष्ठति कूले, वृक्षस्य लम्बते शाखायाम्, शालीनां ते ओदनं ददामि, शालीनां मे ओदनं ददासि ॥ किं पुनः कारणं न सिद्ध्यति? । असमर्थत्वात् ॥

(प्रदीपः) **समर्थनिघाते हीति** । निघात उपलक्षणम् । तेन युष्मदस्मदादेशा अपि गृह्यन्ते ॥ **पटवे ते इति ।** अत्र **समानाधिकरणमसमर्थवद्भवती**ति वाचनिकमसामर्थ्यमिति । असति समानवाक्याधिकारे युष्मदस्मदादेशो न स्यात् । युक्तयुक्तेपि साक्षात् सामर्थ्याभावात् कार्यं न स्यात् । नद्या इत्यादि कारकविशेषणं विज्ञेयम् ॥

(उद्द्योतः) समानवाक्याधिकारफलमाह—भाष्ये—**समर्थनिघाते हीति** । निघाते इत्युक्त्या पटवे ते इत्युदाहरणमनुपपन्नमत आह—**उपलक्षणमिति ॥ कार्यं न स्यादिति** । तिष्ठति लम्बत इत्यादौ निघातो न स्यात्, शालीनां ते इत्यादौ युष्मदाद्यादेशश्च न स्यादित्यर्थः ॥ नन्वाख्यातं **सविशेषण**मिति वाक्यलक्षणं नद्यास्तिष्ठति कूले इत्यादौ नास्तीति कथमत्र निघात इत्यत आह—**नद्या इत्यादीति** । तथा च **सकारकविशेषणमाख्यात**मिति लक्षणेन न दोष इति भावः ॥ वस्तुत **एकतिङि**ति लक्षणेनात्र न दोष इति बोध्यम् । एवं च तत्प्रकरणे समर्थपरिभाषोपस्थितेः फलाभावेनैकार्थीभावसामर्थ्यग्रहणे न कश्चिद्दोष इति तात्पर्यम् ॥

(इति वाक्यलक्षणप्रयोजननिरूपणम्)

(अथ राजगवीक्षीरे समासनिर्णयाधिकरणम्)

(१२०५ आक्षेपवार्तिकम् ॥ १६ ॥)

॥ * ॥ राजगवीक्षीरे द्विसमासप्रसङ्गो द्विषष्ठीभावात् ॥ * ॥

(व्याख्याभाष्यम्)

राजगवीक्षीरे द्विसमासप्रसङ्गः ॥ किं कारणम्? । द्विषष्ठीभावात् । द्वे ह्यत्र षष्ठ्यौ राज्ञः गोः क्षीरमिति ॥

(प्रदीपः) **राजगवीक्षीर इति** । राज्ञो या गौस्तस्याः क्षीरमित्येतस्मिन्नर्थे राजगोक्षीरमित्यपि प्राप्नोति ॥

(उद्द्योतः) अर्थभेदेन समासद्वयस्येष्टत्वात्कथमापत्तिरत

आह—राज्ञो येति । अर्थविशेषे आपत्तिरिति भावः । इयमप्यापत्तिः सर्वपक्षेष्विति बोध्यम् ॥

(आक्षेपबाधकभाष्यम्)

किमुच्यते—'द्विसमासप्रसङ्ग' इति । यदा सुप्सुपेति वर्तते न तदा द्विसमासप्रसङ्ग इति ? ॥

(प्रदीपः) **किमुच्यत इति** । द्वयोः षष्ठ्यन्तयोः समासप्रसङ्ग इत्यर्थं मत्वा पर्यनुयुङ्क्ते ॥ **सुप्सुपेति** । संख्याया विवक्षितत्वात् समुदायस्य चासुबन्तत्वान्नास्ति समासप्रसङ्ग इत्यर्थः ॥

(उद्योतः) द्वौ समासावित्यर्थात्प्रश्नानुपपत्तिरत आह—**द्वयोरिति** । उक्तार्थे स्त्रीत्वापत्तेरयमेवार्थ इति भावः ॥ ननु संख्याविवक्षायामपि समुदायस्यैकत्वादस्त्येव प्रसङ्गोऽत आह—**समुदायस्येति** । प्रत्ययग्रहणपरिभाषयेत्यर्थः ॥

(आक्षेपाशयभाष्यम्)

नैवं विज्ञायते—द्वयोः सुबन्तयोः समासप्रसङ्गो द्विसमासप्रसङ्ग इति ॥ कथं तर्हि ? । द्विप्रकारस्य समासस्य प्रसङ्गो द्विसमासप्रसङ्ग इति ॥ राजगोक्षीरमित्यपि प्राप्नोति ॥

(प्रदीपः) इतरोऽभिप्रायं प्रकाशयति—**नैवमिति** । द्वयोः समासयोः समाहारो द्विसमासं **पात्रादिभ्यः प्रतिषेध** इति स्त्रीत्वाभावः ॥ अमुमेवार्थं शब्दान्तरेण व्यक्तीकरोति—**द्विप्रकारस्येति** ॥ एकस्मिन्नेवार्थे कदाचिद्राजगवीक्षीरं कदाचिद्राजगोक्षीरमिति प्राप्नोतीत्यर्थः ॥

(उद्योतः) **अमुमेवेति** । केचित्तु—द्विप्रकारः समासो द्विसमास इति शाकपार्थिवादित्वान्मध्यमपदलोपिसमासे भाष्यतात्पर्यम् । एवं च पात्रादित्वं न कल्प्यमित्याहुः ॥ अर्थान्तरे तस्यापीष्टत्वादित्यपि प्राप्नोतीत्यसंगतमित्यत आह—**एकस्मिन्निति** ॥

(तृतीयाक्षेपभाष्यम्)

न चैवं भवितव्यम् ? ॥

(तृतीयाक्षेपसमाधानभाष्यम्)

भवितव्यं च यदैतद्वाक्यं भवति—गोः क्षीरं गोक्षीरम्; राज्ञो गोक्षीरं राजगोक्षीरमिति । यदा त्वेतद्वाक्यं भवति—राज्ञो गोः क्षीरमिति, तदा न भवितव्यम्, तदा च प्राप्नोति ॥ तदा कस्मान्न भवति ? ॥

(प्रदीपः) **भवितव्यं चेति** । अर्थान्तर इत्यर्थः । तथा च गवावच्छिन्नं क्षीरं राजस्वामिकमिति प्रतीयते । गौस्तु राजविशिष्टा न प्रतीयते ॥

(१२०६ समाधानवार्तिकम् ॥ १७ ॥)

॥ * ॥ सिद्धं तु राजविशिष्टाया गोः क्षीरेण सामर्थ्यात् ॥ * ॥

(व्याख्याभाष्यम्)

सिद्धमेतत् ॥ कथम् ? । राजविशिष्टाया गोः क्षीरेण सह समासो भवति, न केवलायाः ॥ किं वक्तव्यमेतत् ? । नहि ॥ कथमनुच्यमानं गंस्यते ? । यथैवायं गवि यतते, न च क्षीरमात्रेण संतोषं करोति । एवं राजन्यपि यतते राज्ञो या गौस्तस्या यत् क्षीरमिति ॥

(प्रदीपः) **राजविशिष्टाया इति** । ततश्च गोः पूर्वं राज्ञा संबन्धः पश्चात् क्षीरेणेत्यर्थः ॥

(उद्योतः) **गोः पूर्वमिति** । येन क्रमेण संबन्धस्तत्क्रमेणैव समासशास्त्रप्रवृत्तिरिति भावः ॥

(समाधानान्तरभाष्यम्)

नैव वा पुनरत्र गो राजानमपेक्षमाणायाः क्षीरेण सह समासः प्राप्नोति ॥ किं कारणम् ? । असामर्थ्यात् ॥ कथमसामर्थ्यम् ? । सापेक्षमसमर्थं भवतीति ॥

(प्रदीपः) **नैव वेति** । सत्यपि गोरुभाभ्यां संबन्धे **सापेक्षमसमर्थं भवतीति** असामर्थ्याद् गोः क्षीरेण समासो न भवति, राज्ञा तु भवति राजापेक्षया गोः प्राधान्यात् ॥ एतदुक्तं भवति महत्कष्टं श्रित इत्यत्रैवास्यार्थस्य विचारितत्वान्न पुनश्चोदनीयं *राजगवीक्षीरे द्विसमासप्रसङ्ग* इति ॥

(उद्योतः) युगपत्संबन्धमङ्गीकृत्यापि भाष्ये—**नैव वेति** परिहारान्तरमित्याह—**सत्यपीति** । सापेक्षमुपसर्जनमसमर्थमित्यङ्गीकृत्य परिहारश्चेत् पुनरुक्तमित्यत आह—**एतदुक्तमिति** ॥ **महत्कष्टं श्रित इत्यत्रेति** । राजगवाश्वपुरुषा इत्यत्र चेत्यपि बोध्यम् ॥ न च येन विधिरित्यत्र परमगार्ग्यायण इत्यादौ परमगार्ग्येति समासैकदेशगार्ग्यशब्दात् फगुक्तिर्भाष्योक्ताऽसंगता स्याद्, गार्ग्यस्य परमसापेक्षत्वादिति वाच्यम् । तत्रैकोपस्थितिविषयत्वेनेतरसाकाङ्क्षत्वरूपसापेक्षत्वाभावात् ॥ **सविशेषणानां वृत्तिर्न**त्यत्र सविशेषणत्वमप्याकाङ्क्षालभ्यविशेषणवत्त्वमेवेति न दोषः ॥

(आक्षेपभाष्यम्)

कथं तर्हि गोः क्षीरमपेक्षमाणाया राज्ञा सह समासो भवति ? ॥

(समाधानभाष्यम्)

प्रधानमत्र तदा गौर्भवति । भवति च प्रधानस्य सापेक्षस्यापि समासः ॥

(पदविधिग्रहणप्रयोजनाधिकरणम्)

(आक्षेपभाष्यम्)

अथ किमर्थं पदविधौ समर्थाधिकारः क्रियते ? ॥

(प्रदीपः) **समर्थाधिकार इति** । पारार्थ्यसामान्यात्परिभाषाऽधिकारशब्देनोक्ता । विनियोगो ह्यधिकारः । स च परिभाषायामप्यस्ति । तथा च **कुप्वोः ≍क≍पौ चे**त्यत्र वक्ष्यते—**अधिकारो नाम त्रिप्रकार** इति ॥ अत्र **पद**ग्रहणस्याक्षेपः । समर्थो विधिरित्येव वक्तव्यम् ॥

(उद्योतः) **विनियोगः** । शास्त्रान्तरे उपस्थितिः ॥

(१२०७ समाधानवार्तिकम् ॥ १८ ॥)

॥ * ॥ पदविधौ समर्थवचनं वर्णाश्रये शास्त्र आनन्तर्यविज्ञानात् ॥ * ॥

(व्याख्याभाष्यम्)

पदविधौ समर्थाधिकारः क्रियते । वर्णाश्रये शास्त्रे आनन्तर्यमात्रे कार्यं यथा विज्ञायेतेति । 'तिष्ठतु दध्यशान त्वं शाकेन' 'तिष्ठतु कुमारी च्छत्रं हर देवदत्तेति ॥

(प्रदीपः) **आनन्तर्यमात्र इति** । विनापि सामर्थ्येनेत्यर्थः ॥ **तिष्ठतु कुमारीच्छत्रमिति** । दीर्घादिति नित्यस्तुग् भवति । यस्तु **पदान्ताद्वेति** विकल्पितः स पदविधित्वादसामर्थ्ये न भवतीत्याहुः ॥ अन्ये तु **पदाद्वेत्येव** दीर्घेण पदे विशेष्यमाणे लब्धे तदन्तत्वेन्तग्रहणात्पदात्तुको विप्रकर्षो विज्ञायते—'पदान्तस्य दीर्घस्य तुग् भवति', न तु 'दीर्घान्तस्य पदस्ये'ति पदविधित्वाभावादसत्यपि सामर्थ्ये वा तुग् भवतीत्याहुः ॥

(उद्योतः) **नित्यस्तुगिति** । असति पदग्रहणेऽत्रापि समर्थपरिभाषोपस्थितौ प्रकृते तुग्न स्यादिति भावः ॥ **इत्याहुरिति** । अत्रारुचिबीजं त्वेकार्थीभावसंबवात्र सामर्थ्यस्य ग्रहणमिति पक्षे कुमारी छादयतीत्यत्रासमासे न स्यादिति ॥ **अन्ये त्विति** । तुग्विभावन्तग्रहणं साक्षात्पदोद्देश्यकविधावेव समर्थपरिभाषाप्रवृत्तिरित्यर्थबोधनद्वारा प्रकृते तत्प्रवृत्तिबाधनार्थमिति भावः ॥ एवमन्यत्रापि पदान्तग्रहणेपूह्यम् ॥

(निर्देशानर्थक्यपरिहाराधिकरणम्)

(१२०८ आक्षेपवार्तिकम् ॥ १९ ॥)

॥ * ॥ समर्थाधिकारस्य विधेयसामानाधिकरण्यान्निर्देशानर्थक्यम् ॥ * ॥

(व्याख्याभाष्यम्)

समर्थाधिकारोयं विधेयेन समानाधिकरणः । किं च विधेयम् ? । समासः ॥ यावद् ब्रूयात्—'समर्थः समासः' इति, तावत्—'समर्थः पदविधिः' इति । न च राजपुरुष इत्येतस्यामवस्थायां समर्थाधिकारेण किंचिदपि शक्यं प्रवर्तयितुं निवर्तयितुं वा । समर्थाधिकारस्य विधेयसामानाधिकरण्याद् निर्देशोनर्थकः ॥

(प्रदीपः) **समर्थाधिकारस्येति** । विधिशब्द इह कर्मसाधन एव उपात्तः, तस्य पदसंबन्धी समासादिरर्थो वाच्यः ॥ तत्समानाधिकरणं च समर्थ इत्युपात्तम् । तत्र असमर्थानां पदानां समासस्यानिर्वर्तितत्वात्समर्थवचनेन न किंचित् कृत्यमित्यर्थः । तथा हि । समर्थानां यः समासः स समर्थ एव । योप्यसमर्थानां भार्या राज्ञः पुरुषो देवदत्तस्येत्यादौ सोपि नियमाभावान्निर्वृत्त एव । तस्यासमर्थस्यापि अनेन समर्थवचनेन न किंचित्क्रियते । निष्पन्नत्वाल्लक्षणान्तरेण साधुत्वव्यवस्थापनाच्च । अकिंचित् कुर्वाणमित्यादयोप्यसमर्था नञ्समासाः परिगणनेन निरस्ता इति तदर्थमप्येतन्न भवति ॥

(उद्योतः) **कर्मसाधन इति** । भावसाधने तु समासाद्यसंग्रहः स्यात् तद्विधिभिः पदकर्मकविधानाभावादित्याहुः ॥ नन्वसमर्थानां समासनिवृत्तिरेव तत्फलमत आह—**तत्रेति** । नहि समासनिष्ठसामर्थ्यबोधकेन स निवर्त्तयितुं शक्य इति भावः ॥ ननु तस्य साधुत्वनिवृत्तिरेव तत्फलमत आह—**लक्षणान्तरेणेति** । न च तत्तल्लक्षणैः प्राप्तसाधुत्वस्य समासादेर्लोकसिद्धसामर्थ्याभाववतोऽसाधुत्वमनेन बोध्यत इति न दोष इति वाच्यम् । प्रकारान्तरेणैव सार्थक्यसंभवेन जातस्यासाधुत्वसंपादनापेक्षया समासाद्यप्राप्त्युपपादनस्यैवोचितत्वादिति भावः ॥

(१२०९ समाधानवार्तिकम् ॥ २० ॥)

॥*॥ सिद्धं तु समर्थानामिति वचनात् ॥*॥

(व्याख्याभाष्यम्)

सिद्धमेतत् ॥ कथम् ? ॥ समर्थानां पदानां विधिर्भवतीति वक्तव्यम् ॥

(प्रदीपः) **सिद्धं त्विति** । वचनाद्याख्यानादित्यर्थः । समर्थपदसंबन्धित्वात् पदविधिरुपचारात्समर्थशब्देनोच्यते ॥

(उद्योतः) **उपचारादिति** । लोके गौणानामपि साधुत्वदर्शनादिति भावः ॥

(आक्षेपभाष्यम्)

एवमपि श्लोकयोर्न प्राप्नोति ॥

(प्रदीपः) इतरस्तु पाठोयमिति मत्वाह—**एवमपीति** । यथा **पशुना यजेतेति** गुणेषु संख्या विवक्ष्यते तथेहापि बहुत्वस्य विवक्षितत्वात् ॥

(उद्योतः) **गुणेष्विति** । ननु पदोद्देशेन विधीयमानस्य समर्थेषु नियमनार्थमिदं शास्त्रमिति ग्रहं संमार्ष्टीतिवदुद्देश्यगततया संख्याया अविवक्षैव स्यादिति चेन्न । यूपांश्छिनत्ति अग्नीनादधीतेतिवदुद्देश्यत्वेपि एकवचनेनैव प्रयोगोपपत्तौ बहुवचनकरणेन बहुत्वसंख्या विवक्षेति तात्पर्यम् । मूले तु संख्याविवक्षामात्रे दृष्टान्त उक्त इति ध्येयम् ॥

एवमपि श्लोकयोर्न प्राप्नोतीत्युत्तरं भाष्ये—शब्दसंस्काराथमेव बहुत्वविवक्षया कृतं बहुवचनं तच्च कार्यानन्वयितयाऽविवक्षितमिति समाधानं त्रुटितम् । अन्यथैकशेषनिर्देशाद्वेति वाशब्दासंगतिः ॥

(१२१० समाधानवार्तिकम् ॥ २१ ॥)

॥ * ॥ एकशेषनिर्देशाद्वा ॥ * ॥

(व्याख्याभाष्यम्)

अथ वा एकशेषनिर्देशोयम् । समर्थस्य च समर्थयोश्च समर्थानां च समर्थानामिति ॥

(आक्षेपभाष्यम्)

एवमपि षट्प्रभृतीनामेव प्राप्नोति । षट्प्रभृतिषु ह्येकशेषः परिसमाप्यते ॥

(उद्योतः) **षट्प्रभृतीनामिति** । कपिञ्जलाधिकरणन्यायानाश्रयणात् ॥

(समाधानभाष्यम्)

नैष दोषः । प्रत्येकं वाक्यपरिसमाप्तिर्दृष्टेति द्व्येकयोरपि भविष्यति ॥

(प्रदीपः) **प्रत्येकमिति** । आश्रितसंख्याविशेषाणां कृतैकशेषाणां पुनरेकशेषकरणसामर्थ्यात् ॥

(उद्योतः) **आश्रितसंख्येति** । अन्यथैकवचनान्तानामेव षण्णां पदानामेकशेषः कृतः स्यादिति भावः । एवं चैकमेवेदमेकत्वद्वित्वबहुत्वविशिष्टानर्थानुपस्थापयतीति तात्पर्यम् ॥

(आक्षेपभाष्यम्)

एवमपि विभक्तीनां न प्राप्नोति—समर्थात्समर्थे पदात्पद इति ।

(प्रदीपः) **एवमपीति** । सर्वमेतद्वाचनिकमिति मत्वा पुनः पर्यनुयुङ्क्ते ॥ **समर्थादिति** । तिङ्ङतिङ इत्यादौ ॥ **समर्थ इति** । यथा कुत्सने च सुप्यगोत्रादाविति ॥

(उद्योतः) ननु पदविधिरिति समासः । तत्र विशेषानवगमात्पदात्पदे इति असंगतमत आह—**सर्वमिति** । अन्यथा राजपुरुषादिवत्संख्याविशेषस्याप्यनवगतिः स्यादिति पूर्वोक्तमप्यनुपपन्नं स्यादिति पदविधिरिति त्यक्त्वा पदानामित्यपि वाचनिकमिति भावः॥ **तिङ्ङतिङ** इति । निघातादिप्रकरणेपि समर्थपरिभाषोपतिष्ठत इति मतेनेदम् ॥ तद्धितविधौ **प्रातिपदिकादि**त्यस्योपलक्षणमेतत् । सप्तमीसमासफलं **तद्धितार्थोत्तरपदे**ति ॥

(समाधानभाष्यम्)

एवं तर्हि समर्थपदयोरयं विधिशब्देन सर्वविभक्त्यन्तः समासः—समर्थस्य विधिः समर्थविधिः, समर्थयोर्विधिः समर्थविधिः, समर्थानां विधिः समर्थविधिः, समर्थाद्विधिः समर्थविधिः, समर्थे विधिः समर्थविधिः । पदस्य विधिः पदविधिः, पदयोर्विधिः पदविधिः, पदानां विधिः पदविधिः, पदाद्विधिः पदविधिः, पदे विधिः पदविधिः । समर्थविधिश्च समर्थविधिश्च समर्थविधिश्च समर्थविधिश्च समर्थविधिश्च समर्थविधयः । पदविधिश्च पदविधिश्च पदविधिश्च पदविधिश्च पदविधिश्च पदविधयः । समर्थविधयश्च पदविधयश्च समर्थः पदविधिः । पूर्वः समास उत्तरपदलोपी । याद‍ृच्छिकी विभक्तिश्च ॥

(प्रदीपः) **पूर्वसमास उत्तरपदलोपीति** । गतार्थत्वाद्विधिशब्दस्याप्रयोग इत्यर्थः । समर्थपदाश्रयत्वाद्विधिरेव समर्थशब्देनोच्यत इत्यर्थः । संबन्धसामान्यवचनषष्ठ्यन्तस्य च पदशब्दस्य विधिशब्देन समासे विभक्त्यन्तरार्थोऽप्यन्तर्भवतीति सर्वं सूत्रेणैव सिध्यति ॥ **याद‍ृच्छिकी विभक्तिरिति ।** भेदाभेदविवक्षासंभवे सति यदृच्छया अभेदविवक्षामाश्रित्य प्रथमया निर्देशः कृत इत्यर्थः ॥

(उद्योतः) **समर्थविधयश्चेति** । सूत्रे जात्यभिप्रायेणैकवचनम् ॥ सूत्रे समर्थ इत्यस्य भिन्नपदत्वात् शाकपार्थिवादिवदुत्तरपदलोपासंभवादाह—**गतार्थेति** ॥ **संबन्धेति** । विधिशब्दस्य कर्मसाधनत्वाद् शेषषष्ठ्यन्तेन समास इति भावः ॥ **अन्तर्भवतीति ।** सर्वस्यापि विभक्त्यर्थस्य संबन्धत्वानपायादित्यर्थः ॥ नन्वेवमपि लक्षणामनङ्गीकृत्य स्पष्टप्रतिपत्तये षष्ठ्यैवोच्चिनेत्यतो भाष्ये उक्तम् **याद‍ृच्छिकीति** । तदभिप्रायमाह—**भेदेति** । लक्षणयाऽभेदविवक्षा अन्यथा भेदविवक्षेत्यर्थः । सर्वविभक्तीनां यौगपद्येन प्रयोगासंभवादिति भावः ॥

(सामानाधिकरण्योपपादनाधिकरणम्)

(१२११ आक्षेपवार्तिकम् ॥ २२ ॥)

॥ * ॥ समानाधिकरणेषूपसंख्यानमसमर्थत्वात् [द्रव्यं पदार्थ इति चेत्] ॥ * ॥

(भाष्यम्) **समानाधिकरणेषूपसंख्यानं कर्तव्यम् । वीरः पुरुषो वीरपुरुषः ॥ किं पुनः कारणं न सिद्ध्यति ? । असमर्थत्वात् ॥ कथमसामर्थ्यम् ? । द्रव्यं पदार्थ इति चेत् । यदि द्रव्यं पदार्थः, न भवति तदा सामर्थ्यम् । भेदाभावात् । अथ हि गुणः पदार्थः, भवति तदा सामर्थ्यम् । अन्यो हि वीरत्वं गुणः, अन्यो हि पुरुषत्वम् ॥**

(प्रदीपः) **समानाधिकरणेष्विति** । केचिदाचार्या द्रव्यं पदार्थं प्रतिपन्नाः । केचिदाकृतिम् । गुणशब्देनाप्याकृतिरुच्यते यथा **यस्य गुणस्य भावादि**ति ॥

संसर्गिभेदकं यद्यत् सव्यापारं प्रतीयते ।

गुणत्वं परतन्त्रत्वात्तस्य शास्त्र उदाहृतम् ॥ इति

गुणलक्षणयोगात्तत्र द्रव्ये पदार्थे वीरः पुरुष इत्येताभ्यां द्रव्यमेकमभिधीयते न तु वीरत्वं पुरुषत्वं च । तत्र भेदाभावे भेदाधिष्ठानस्य संसर्गस्येहासंभवाद् असति सामर्थ्ये समासो न प्राप्नोतीति वचनम् ॥ **अथ हि गुण इति** । वीरत्वं पुरुषत्वं चैकव्यक्तिगतमेताभ्यामभिधीयत इति भेदपूर्वकः संसर्गोऽस्तीति भावः ॥

(उद्योतः) **प्रतिपन्नाः** । सर्वशब्दवाच्यत्वेन गृहीतवन्तः । अत्र **द्रव्य**शब्देन प्रवृत्तिनिमित्ताश्रय उच्यते । अत एव रूपादिशब्दसंग्रहः ॥ **आकृतिमिति** । आकृतिशब्देन प्रवृत्तिनिमित्तमुच्यते ॥ नन्वेवं भाष्ये कथम**थ हि गुण** इत्युक्तमत आह—**गुणशब्देनेति** ॥ **संसर्गिभेदकमिति** । संसर्गिणि इतरभेदानुमापकमित्यर्थः ॥ **सव्यापारमिति** । स्वविषयशक्तिग्रहेण स्वाश्रयोपस्थाप-

कत्वरूपव्यापारवदित्यर्थः ॥ स्वावच्छिन्नत्वेन सकलव्यक्त्युपस्थापकत्वव्यापारवदित्यर्थो वा ॥ **इत्येताभ्यामिति** । पदद्वयेन शुद्धद्रव्यविशेषस्योपस्थितिरित्यर्थः ॥ **भेदाधिष्ठानस्येति** । अन्यथा घटोघट इत्यपि स्यादिति भावः । पदार्थानां परस्परं विशेष्यविशेषणभावरूपसंसर्ग एव हि सामर्थ्यमिति तात्पर्यम् ॥ **एकव्यक्तिगतमिति** । तत्तद्विशेषणवैशिष्ट्येन भेदात्तयोर्विशेष्यविशेषणभावलक्षणसंसर्गोस्तीति भावः । विशेषणत्वादि संबन्धनियतमेवेत्यत्र तु न मानमिति तात्पर्यम् ॥

(अन्यत्वस्य सामर्थ्यहेतुत्वबाधकभाष्यम्)

न 'अन्यत्वमस्ति' इतीयता सामर्थ्यं भवति। अन्यो हि देवदत्तो गोभ्यश्चाश्वेभ्यश्च। न च तस्यैतावता सामर्थ्यं भवति ॥

(प्रदीपः) **नान्यत्वमिति** । उपकारविवक्षायां सामर्थ्यम्, नान्यत्वमात्रेणेत्यर्थः ॥

(उद्द्योतः) **उपकारेति** । विशेष्यविशेषणभावेनान्वयरूपोपकारेत्यर्थः । अन्यथा देवदत्ताश्वयोरपि कर्मधारयप्रयोजकं सामर्थ्यं स्यादिति भावः ॥

(प्रत्याक्षेपभाष्यम्)

को वा विशेषः यद् गुणे पदार्थे सामर्थ्यं स्यात्। द्रव्ये च न स्याद्? ॥

(प्रत्याक्षेपसमाधानभाष्यम्)

एष विशेषः। एकं तयोरधिकरणम्। अन्यश्च क्षीरत्वं गुणः, अन्यः पुरुषत्वम् ॥

(प्रदीपः) **एकं तयोरिति** । ततस्तद्वारेणास्ति विशेषणविशेष्यभावः ॥

(समाधानबाधकभाष्यम्)

द्रव्यपदार्थिकस्यापि तर्हि गुणभेदात्सामर्थ्यं भविष्यति ॥

(प्रदीपः) **द्रव्यपदार्थिकस्यापीति** । एकमपि द्रव्यं भिन्नगुणसंसर्गाद् भेदकार्यं लभते ॥

(उद्द्योतः) **भेदकार्यम्** । परस्परविशेषणविशेष्यभावरूपम् ॥

(समाधानसाधकभाष्यम्)

अशक्यो द्रव्यपदार्थिकेन द्रव्यस्य गुणकृत उपकारः प्रतिज्ञातुम् ॥

(प्रदीपः) **अशक्य इति** । भेदहेतोर्विद्यमानस्यापि गुणस्य शब्देनावाच्यत्वादित्यर्थः ॥

(समाधानबाधकभाष्यम्)

ननु चाभ्यन्तरोसौ भवति ॥

(प्रदीपः) **ननु चेति** । द्रव्यस्य गुणेन नित्यसंबन्धादित्यर्थः ॥

(उद्द्योतः) **द्रव्यस्येति** । एवं च स्मर्यमाणगुणकृतभेदमादाय विशेषणविशेष्यभाव इत्यभिमानः ॥

(समाधानसाधकभाष्यम्)

यद्यप्यभ्यन्तरः, न तु गम्यते। नहि गुड इत्युक्ते मधुरत्वं गम्यते, शृङ्गवेरमिति वा कटुकत्वम् ॥

(प्रदीपः) **यद्यपीति** । अनभिधीयमानोपि संनिधिनैव परिच्छेदहेतुत्वादभ्यन्तरः ॥ **न तु गम्यत इति** । शब्देन नोच्यत इत्यर्थः ॥

(उद्द्योतः) नन्वभ्यन्तरत्वेभिधीयमानोपि स्यादत आह—**अनभिधीति** । **संनिधिना** स्मृतिमात्रेण ॥ **शब्देनेति** । वृत्त्यभावादभ्यन्तरस्यापि तस्य विशेष्यविशेषणभावेन प्रतीतिप्रयोजकता नेत्यर्थः । अयं भावः—द्रव्येण नित्यसंबन्धिनो बहवो गुणाः नहि सर्वेषां सर्वदा स्मरणमनुभूयते इति शब्दजन्योपस्थितिं विना भेदकत्वं वक्तुमशक्यमिति भावः ॥

(समाधानबाधकभाष्यम्)

गुणपदार्थिकेनापि तर्हि अशक्यो गुणस्य द्रव्यकृत उपकारः प्रतिज्ञातुम्।

(प्रदीपः) **गुणपदार्थिकेनापीति** । यद्यवाच्यस्योपकारकत्वं नाश्रीयत इत्यर्थः ॥ अथावाच्यस्याप्युपकारकत्वमाश्रीयते तदा पक्षद्वयेपि साम्यम् ॥

(उद्द्योतः) **यद्यवाच्यस्येति** । गुणवादेपि द्रव्यस्यावाच्यत्वेन तद्द्वारकं सामर्थ्यं वक्तुं न शक्यमिति भावः ॥ **अथावाच्यस्येति** । एवं रीत्या द्रव्यवादिनः प्रवृत्तिनिमित्तमपि उपकारकं भविष्यतीति भावः । द्रव्यवादे गुणस्यावाच्यत्वं नाम शक्त्यविषयत्वम् । शक्यतावच्छेदके शक्त्यभावात् । गुणवादे द्रव्यमप्येवमिति तात्पर्यम् ॥

(समाधानसाधकभाष्यम्)

अथ गुणपदार्थिकः प्रतिजानीते ॥

(उद्द्योतः) भाष्ये—**प्रतिजानीते इति** । समानाधिकरणयोः समासमिति शेषः ॥

(प्रतिबन्दीभाष्यम्)

द्रव्यपदार्थिकोपि कस्मान्न प्रतिजानीते? ॥

(उद्द्योतः) **न प्रतिजानीत इति** । प्रतिजानीतएवेत्यर्थः ॥

(प्रतिबन्दीबाधकभाष्यम्)

एवमनयोः सामर्थ्यं स्याद्वा न वा ॥

(उद्द्योतः) इतर एवमाशयमजानानः प्रतिबन्दीमात्रात्तार्थसिद्धिरित्याह—**एवमनयोरिति** ॥

(प्रत्याक्षेपभाष्यम्)

क च तावदिदं स्यात्—समानाधिकरणेनेति? ॥

(प्रदीपः) **क च तावदिति** । यद्यवाच्यस्योपकारकत्वं नाश्रीयेत इत्यर्थः ॥

(उद्द्योतः) असामर्थ्यात्समासाभावनिश्चय एवेत्याशयेनाह—**कचेति** ॥ **समानाधिकरणेनेति** । विशेषणं विशेष्येण समानाधिकरणेनेतीत्यर्थः ॥

(प्रत्याक्षेपबाधकभाष्यम्)

यत्र सर्वं समानम्—'इन्द्रः शक्रः पुरुहूतः पुरंदरः' 'कन्दुः कोष्ठः कुसूलः' इति ॥

(प्रदीपः) **यत्र सर्वमिति** । समानमेकमधिकरणमभिधेयं यस्य तेन पर्यायेणेत्यर्थ इति मन्यते । ततश्च यत्र प्रवृ-

[illegible]प्येकं वाच्यं च तच्चैव स्यादित्यर्थः ॥ कथं पुनरत्र विशेषणविशेष्यभावः ?। उच्यते—कश्चित् प्रति कयाचित् संज्ञया सोऽर्थः प्रसिद्धोऽन्यया त्वप्रसिद्ध इति प्रसिद्धस्य विशेषणत्वम्, इतरस्य तु विशेष्यत्वम् ॥

(उद्द्योतः) सर्वसाम्ये भेदनिबन्धनविशेषणविशेष्यभावः सामानाधिकरण्यं च सर्वथा दुरुपपादमित्यत आह—**अभिधेयं यस्येति** । वाच्यपर्यायोऽधिकरणशब्द इत्यर्थः ॥ **वाच्यं चेति** । प्रवृत्तिनिमित्ताश्रयभूतमित्यर्थः ॥ **विशेषणत्वमिति** । परिच्छेदकत्वमित्यर्थः । विशेषणं विशेष्येणेतिसूत्रे परिच्छेद्यपरिच्छेदकभाव एव विशेषणविशेष्यभाव इत्यभिमानः ॥

(प्रत्याक्षेपसाधकभाष्यम्)

नैवंजातीयकानां समासेन भवितव्यं प्रत्ययेन वोत्पत्तव्यम् ॥ किं कारणम् ?। अर्थगत्यर्थः शब्दप्रयोगः । अर्थं संप्रत्याययिष्यामीति शब्दः प्रयुज्यते । तत्रैकेनोक्तत्वात्तस्यार्थस्य द्वितीयस्य प्रयोगेण न भवितव्यम् । किं कारणम्? । उक्तार्थानामप्रयोग इति ॥

(प्रदीपः) **नैवंजातीयकानामिति** । युगपत्प्रयोगाभावात् सामर्थ्याभावाचेत्यर्थः ॥

(उद्द्योतः) एवंजातीयकानामिति भाष्यस्य पर्यायाणामित्यर्थस्तदाह—**युगपदिति** ॥ **सामर्थ्याभावाच्चेति** । भेदनिबन्धनविशेषणविशेष्यभावरूपस्य तन्मूलैकार्थीभावरूपस्य च सामर्थ्यस्याभावादित्यर्थः । विषयतारूपविशेषणत्वाचेव तत्र निविष्टमिति भावः ॥ भाष्ये—**प्रत्ययेन वोत्पत्तव्यमिति** । पर्यायाणां सहप्रयोगे आकाङ्क्षाविरहात् बोधेन न भवितव्यमित्यर्थः । प्रत्ययशब्दो ज्ञानपर इति बोध्यम् ॥

(आक्षेपभाष्यम्)

न तर्हीदानीमिदं भवति—भृत्यभरणीय इति ?॥

(प्रदीपः) **भृत्यभरणीय इति** । अस्ति चायं शिष्टप्रयोग इति भावः ॥

(उद्द्योतः) **शिष्टेति** । तथा चाविगीतं साधुत्वं भाष्यस्थतर्हिशब्देन सूचितम् ॥

(समाधानभाष्यम्)

नैतौ समानार्थौ । एकोऽत्र शक्यार्थे कृत्यः, अपरोऽर्हे । शक्यो भर्तुं भृत्यः । अर्हति भृतिं [भरणीयः । भृत्यो भरणीयो भृत्य] भरणीय इति ॥

(प्रदीपः) **नैताविति** । उपाधिभेदाद्भिन्नार्थावित्यर्थः ॥

(उद्द्योतः) **उपाधीति** । कर्मरूपार्थसाम्येपि शक्यत्वार्हत्वरूपोपाधिभेदादित्यर्थः । भृत्यभरणीयवदेव वीरपुरुषादिरप्युदाहरणमिति भावः ॥

(आक्षेपभाष्यम्)

यदि तर्हि यत्र किंचित्समानं कश्चिच्च विशेषस्तत्र भवितव्यम् । इहापि तर्हि प्राप्नोति—दर्शनीयाया माता दर्शनीया मातेति । अत्रापि किंचित्समानं कश्चिच्च विशेषः । किं पुनस्तत् ? । सद्भावान्यभावौ ॥

(प्रदीपः) **दर्शनीया मातेति** । यदि सति भेदे किंचित् समानमाश्रित्य समासः क्रियते तदा यथा वीरपुरुष इत्यत्रानभिधीयमानमपि द्रव्यं समानमाश्रित्य समासः क्रियते तथात्रापि सत्ता समानेति समासः प्राप्नोतीत्यर्थः ॥ ननु परत्वादपवादत्वाद्वात्र षष्ठीसमासो भविष्यति । नैतदस्ति । समानाधिकरणेन नेति प्रतिषेधः प्राप्नोति । विधेः कोऽवकाश इति चेद् इष्टा त्विह व्यवस्था न स्यात् । समानाधिकरणोत्तरपदलक्षणश्च पुंवद्भावः प्रसज्येत ॥ **सद्भावान्यभावाविति** । सत्तान्यत्वे इत्यर्थः ॥

(उद्द्योतः) **यदि सति भेदे इति** । अयं पूर्वपक्षोऽधिकरणशब्दस्य पदार्थपरत्वमाश्रित्य तत्पक्षेपि शब्दो नान्यपदार्थः । किं तर्हि? अर्थ एव । तथा च समानमधिकरणं पदार्थो यस्याश्रयत्वेनाधेयत्वेन वा स समानाधिकरणस्तत्तद्वाचके लक्षणेत्याशयेन । अत एव न वक्ष्यमाणतृतीयसमाधानासंगतिरित्याहुः ॥ **अनभिधीयमानमपीति** । आक्षिप्तमित्यर्थः । शक्तिग्रहाविषय इत्यर्थो वा ॥ **समासः प्राप्नोतीति** । कर्मधारय इत्यर्थः ॥ भाष्ये—**कश्चिच्च विशेष इति** । दर्शनीयत्वं मातृत्वं चेत्यर्थः ॥ **सत्तान्यत्वे इति** । पदार्थवाचिभावशब्देन न कर्मधारयः, किंतु त्वार्थवाचकेन भावशब्देन षष्ठीतत्पुरुष इति भावः ॥

(समाधानभाष्यम्)

न कचित्सद्भावान्यभावौ न स्तः, उच्यते चेदं समानाधिकरणेनेति, तत्र प्रकर्षगतिर्विज्ञास्यते—यत्र साधीयः सामानाधिकरण्यम् ॥ क्व च साधीयः सामानाधिकरण्यम् ? । यत्र सर्वं समानं सद्भावान्यभावौ द्रव्यं च ॥

(उद्द्योतः) भाष्ये—**न क्वचिदिति** । तयोः केवलान्वयित्वादिति भावः ॥

(समाधानान्तरभाष्यम्)

अथ वा समानाधिकरणेनेति तत्समानमाश्रीयते यत्समानं भवति, न भवति च । न चैतत्समानं कचिदपि न भवति ॥

(प्रदीपः) **न चैतदिति** । सत्तायाः सर्वत्र भावाद् व्यभिचाराभावान्नासौ समानत्वेनाश्रीयते । पूर्वः परिहारः समानत्वमभ्युपगम्य पुनः श्रुत्या प्रकर्षाश्रयेणोक्तः । उत्तरस्तु सर्वसाधारण्यात् सत्तायाः समानव्यपदेशं प्रति निमित्तत्वानाश्रयणेनाभिहितः ॥

(उद्योतः) व्यभिचाराभावादिति । एवं च समानाधिकरणपदव्यावर्त्यालाभ इति भावः ॥ नासौ समानत्वेनेति । समानव्यवहारनिमित्तत्वेनेत्यर्थः ॥ समानत्वमिति । समानव्यवहारनिमित्तत्वमभ्युपगम्येत्यर्थः ॥

(समाधानान्तरभाष्यम्)

अथ वा यावद् ब्रूयात्—समानद्रव्येणेति, तावत्—समानाधिकरणेनेति । द्रव्यं हि लोके 'अधिकरणम्' इत्युपचर्यते । तद्यथा—'एकस्मिन्द्रव्ये व्युदितम्' । एकस्मिन्नधिकरणे व्युदितम् । तथा व्याकरणे 'विप्रतिषिद्धं चानधिकरणवाचि' अद्रव्यवाचीति गम्यते ॥

(प्रदीपः) अथ वेति । अधिकरणशब्दोभिधेयवाचीति पर्यनुयोगो द्रव्यवाचीति समाधानम् ।· दर्शनीयाया मातेत्यत्र तु द्रव्यभेदः । अभिधेयस्य तु सत्तायाः समानत्वात् समानत्वं स्यात् ॥ व्युदितमिति । विवादः कृत इत्यर्थः ॥

(उद्योतः) अभिधेयवाचीति । अभिधेयत्ववद्वाऽभिधेयशब्देन पदार्थमात्रमुच्यते ॥ द्रव्यवाचीति । समानशब्दश्चैकत्ववाची सूत्रे ॥ अभिधेयस्य त्विति । वाच्यस्य त्वित्यर्थः । तच्च धर्मो वा द्रव्यं वेत्यन्यत् । तस्य च सत्तया समानत्वमस्त्येव । तत्पक्षे समानशब्दो नैकपर्याय इति भावः ॥

(आक्षेपभाष्यम्)

एवमपीदमवश्यं वक्तव्यम्—'समानाधिकरणमसमर्थवद्भवति' इति ॥ किं प्रयोजनम्? । सर्पिःकालकं यजुःपीतकमित्येवमर्थम् ॥

(प्रदीपः) सर्पिःकालकमिति । इसुसोः सामर्थ्य इति षत्वनिवारणार्थं वाचनिकमसामर्थ्यमिति वीरपुरुष इति समानाधिकरणसमासोऽपि न स्यादित्यर्थः ॥

(उद्योतः) पुनः पूर्वपक्षयति प्रकारान्तरेण—भाष्ये—एवमपीदमिति ॥

(प्रत्याक्षेपभाष्यम्)

यदि 'समानाधिकरणमसमर्थवद्भवति' इत्युच्यते सर्पिष्पीयते यजुष्क्रियत इत्यत्र षत्वं न प्राप्नोति ॥

(प्रत्याक्षेपबाधकभाष्यम्)

अधात्वभिहितमित्येवं तत् ॥

(प्रदीपः) अधात्वभिहितमिति । धातुसहचरितः प्रत्ययो धातुशब्देनोक्तः । तेनाभिहितं कर्मादि यदि भवति तदा सामर्थ्यमेवेत्यर्थः ॥

(उद्योतः) कर्मादेर्धात्वभिहितत्वाभावादाह—धातुसहचरित इति ॥ इसुसोरिति सूत्रस्थभाष्यरीत्या तिङां कर्मादिद्योतकत्वे तु यथाश्रुतमेव भाष्यं सम्यक् । एवं च वीरः पचन्नित्यादौ वक्ष्यमाणदोषशङ्कैव नेति बोध्यम् ॥

(उपसंहारभाष्यम्)

एवं च कृत्वा समानाधिकरणेषूपसंख्यानं कर्तव्यम् । वीरः पुरुषो वीरपुरुष इति । किं कारणम्? । असमर्थत्वात्? ॥

(१२१२ समाधानवार्तिकम् ॥ २३ ॥)

॥ * ॥ न वा वचनप्रामाण्यात् ॥ * ॥

(व्याख्याभाष्यम्)

न वा कर्तव्यम् ॥ किं कारणम्? । वचनप्रामाण्यात् । वचनप्रामाण्यादत्र समासो भविष्यति ॥ किं वचनप्रामाण्यम्? । "समानमध्यमध्यमवीराश्च" इति ॥

(प्रदीपः) न वेति । वचनसामर्थ्याद्वाचनिकमसामर्थ्यं बाध्यत इत्यर्थः । वीरः पचन्नित्यादौ तु धात्वभिहिते अनभिधानाद्बहुलग्रहणाद्वा समासाभावं मन्यते ॥

(उद्योतः) ननु वीरपुरुषादन्यत्र कथमित्यत आह—वचनेति । समानाधिकरणसमासप्रकरणे एतद्वचनात्प्रवृत्तिर्ज्ञाप्यत इत्यर्थः ॥ ननु वीरः पचन्नित्यादौ धात्वभिहिते चारितार्थ्यात्कथं ज्ञापकत्वमत आह—वीर इति । बहुलग्रहणस्याप्यनभिधानमूलकत्वादनभिधानादित्येव सारम् ॥

(१२१३ आक्षेपसमाधानातिदेशवार्तिकम् ॥ २४ ॥)

॥ * ॥ लुप्ताख्यातेषु च ॥ * ॥

(व्याख्याभाष्यम्)

लुप्ताख्यातेषु चोपसंख्यानं कर्तव्यम् । निष्कौशाम्बिः निर्वाराणसिः ॥

लुप्ताख्यातेषु च ।

किम्? । वचनप्रामाण्यादित्येव ॥ किं वचनप्रामाण्यम्? । "कुगतिप्रादयः" इति ॥

(प्रदीपः) लुप्ताख्यातेषु चेति । वचनप्रामाण्यादित्यस्योपजीवनार्थमिदं वार्तिकम् । भाष्यकारस्तु प्रपञ्चार्थमुपसंख्यानं प्रतिविधानं च वाक्यभेदेनाचष्टे । आख्यातशब्देन क्रियापदं क्रान्ताद्यपि कथ्यते ॥ निष्कौशाम्बिरिति । पूर्वपदोत्तरपदयोरसामर्थ्यं मन्यते । क्रियाविषयत्वादुपसर्गाणां द्रव्येण संबन्धाभावात् ॥

(उद्योतः) वार्तिकपाठे एकस्यैव वाक्यस्य दर्शनेन कथमुपसंख्याने तन्निषेधे च तात्पर्यमत आह—भाष्यकारस्त्विति ॥ वाक्यभेदेनेति । आवृत्त्येत्यर्थः ॥ आख्यातपदस्य तिङन्ते प्रसिद्धेराह—आख्यातेति । क्रियाबोधकत्वसाम्येन गौण्या वृत्त्येत्यर्थः ॥ असामर्थ्यं मन्यते इति । साक्षादन्वयाभावेनेत्यर्थः ॥

(समाधानबाधकभाष्यम्)

अस्त्यन्यदेतस्य वचने प्रयोजनम् ॥ किम्? । सुराजा अतिराजेति ॥

(उद्द्योतः) भाष्ये—**सुराजातिराजेति**। दुष्कुलम् आकडार इत्यादेरप्युपलक्षणम्॥ एतेन **प्रादय** इति बहुवचनं ज्ञापकमित्यपास्तम्॥

(समाधानाशयभाष्यम्)

न ब्रूमो वृत्तिसूत्रवचनप्रामाण्यादिति। किं तर्हि?। वार्त्तिकवचनप्रामाण्यादिति। *सिद्धं तु काङ्क्षतिदुर्गतिवचनात्*। *प्रादयः क्तार्थे* इति॥

(प्रदीपः) **किं तर्हीति**। वार्त्तिककारवचनस्यापि स्मृतिशास्त्रत्वात् प्रामाण्यमाश्रितमित्यर्थः॥

(उद्द्योतः) **वृत्तिसूत्रेति**। वार्त्तिकेष्वपि सूत्रलक्षणसत्त्वेनार्षत्वेन च सूत्रत्वमभ्युपगम्य पाणिनिसूत्राणां वृत्तिसद्भावाद्वार्त्तिकानां तदभावाच्च तयोर्वैषम्यबोधनायेदम्। वृत्तियुक्तं सूत्रं वृत्तिसूत्रमित्यर्थः॥ क्वचित्तु **वृत्तिः सूत्रेति** पाठः तदा सूत्रप्रामाण्याद्वृत्तिरिति न ब्रूमः किं तर्हि वार्त्तिकप्रामाण्यादितीत्यर्थः। यथाऽ**नेकमन्यपदार्थे** इति शास्त्रबलाद्बहुव्रीहावन्यपदार्थान्तर्भावस्तथा **प्रकृते क्तार्थे** इति वार्त्तिकबलात्तदर्थान्तर्भाव इति भावः॥ **स्मृतिशास्त्रत्वादिति**। अन्यशास्त्रीयवार्त्तिकवत् नासदीयं वार्त्तिकं व्याख्यानमेवेति भावः॥ न च **वचनेत्य**स्यापि वार्त्तिकत्वाद्वार्त्तिककृता स्वीयवचसः कथं प्रमाणत्वेनाश्रयणमिति भाष्ये **वार्तिकेत्या**द्यनुपपन्नमिति वाच्यम्। अन्योयं वार्तिककारो वार्तिककारान्तरीयतद्वचनं प्रमाणान्तरत्वेनाश्रयतीत्यदोषात्॥

(१२१४ समाधानान्तरवार्तिकम्॥ २५॥)

॥ * ॥ तदर्थगतेर्वा ॥ * ॥

(भाष्यम्) **तदर्थगतेर्वा पुनः सिद्धमेतत्॥ किमिदं तदर्थगतेरिति?। तस्यार्थस्तदर्थः तदर्थस्य गतिस्तदर्थगतिस्तदर्थगतेरिति। यस्यार्थस्य कौशाम्ब्या सामर्थ्यं स निसोच्यते॥ अथ वा सोर्थस्तदर्थः तदर्थस्य गतिस्तदर्थगतिस्तदर्थगतेरिति। योर्थः कौशाम्ब्या समर्थः स निसोच्यते॥**

(प्रदीपः) **तस्यार्थ इति**। क्रान्तशब्दस्य योर्थः संप्रतीयते निःशब्देन क्रियाविषयेण तस्यार्थस्य सामर्थ्यादाक्षिप्तत्वात्तद्द्वारेण पूर्वपदोत्तरपदयोः सामर्थ्यादित्यर्थः॥ **सोर्थ इति**। निस एवायं वृत्तिविषये क्रान्तलक्षणोर्थ इति दर्शयति॥

(उद्द्योतः) नन्वन्यशब्दस्यार्थोन्येन कथं वक्तव्य इति **निसोच्यत** इत्यसङ्गतमत आह—**संप्रतीयते इति**। एवं च **निसोच्यत** इत्यस्य क्रियाविषयनिसर्थेनाक्षिप्यत इत्यर्थ इति भावः। तदाह—**निःशब्देनेति**॥ ननु शक्त्यभावे कथं प्रतीतिरत आह—**आक्षिप्तत्वादिति**। भाष्ये—**तस्यार्थ इति**। क्रान्तशब्दस्यार्थ इत्यर्थः। तत्रान्यशब्दार्थस्यान्येन शक्त्या बोधनासंभवात् **उच्यत** इत्यस्याक्षिप्यत इत्यर्थ इति भावः। आक्षिप्तस्यापि शाब्देन्वयबोधे भानं भवतीति भावः॥ तदसहमान आह—**अथ वा सोर्थ इति**। तदाह—**निसएवेति**॥

(अथ समासयोग्यपदसंख्यानिर्णयाधिकरणम्)

(आक्षेपभाष्यम्)

अथ यत्र बहूनां समासप्रसङ्गः किं तत्र द्वयोर्द्वयोः समासो भवति, आहोस्विदविशेषेण?॥

(प्रदीपः) **अथ यत्रेति**। यत्र विशिष्टे पूर्वपदोत्तरपदे उपात्ते यथा **द्वितीयाश्रितेति** तत्र नास्ति बहूनां प्रसङ्गः। यत्र तु विशेषो नोपात्तः **अनेकमन्यपदार्थे चार्थे द्वन्द्व** इति तत्र संदेहः। यदि सुप्सुपेति वर्तते ततो विवक्षितत्वात् संख्यायाः द्वयोर्द्वयोः समासेन भवितव्यम्। अथ निवृत्तं ततो यावतामन्यपदार्थे चार्थे च वृत्तिस्तावतां भवितव्यम्॥ नन्वनेकग्रहणाद् बहूनामपि भाव्यम्। अन्यथा तदनर्थकं स्यात्॥ नैतदस्ति। अनेकग्रहणमुपसर्जनसंज्ञार्थं स्याच्चित्रगुरित्यादौ ह्रस्वार्थम्। यदा त्वेकविभक्तित्वेनोपसर्जनसंज्ञा सिध्यतीत्युच्यते तदानेकग्रहणं सुप्सुपेत्यस्य निवृत्त्यर्थं विज्ञायते। तेन बहूनां समासः सिध्यति॥

(उद्द्योतः) तत्र संशयविषयं दर्शयति—**यत्रेति**॥ **विवक्षितत्वादिति**। सुबन्तत्वस्य प्रत्येकमेव समाप्तेरित्यपि बोध्यम्॥ अनेकस्योपसर्जनत्वे पूर्वनिपातो न फलमित्यत आह—**चित्रगुरिति**॥ **सुप्सुपेत्यस्येति**। तृतीयान्तनिवृत्तौ तात्पर्यम्। प्रथमान्तं तु वर्तत एवेति बोध्यम्॥ **तेन बहूनामिति**। भाष्यं त्वनेकग्रहणाभावं मत्वा कृत्वाचिन्तया प्रवृत्तमिति बोध्यम्॥

(विशेषजिज्ञासाभाष्यम्)

कश्चात्र विशेषः?॥

(१२१५ प्रथमपक्षे दूषणवार्तिकम्॥ २६॥)

॥ * ॥ समासो द्वयोर्द्वयोश्चेद् द्वन्द्वेनेकग्रहणम् ॥ * ॥

(व्याख्याभाष्यम्)

समासो द्वयोर्द्वयोश्चेद् द्वन्द्वेनेकग्रहणं कर्तव्यम्। चार्थे द्वन्द्वोनेकमिति वक्तव्यम्। इहापि यथा स्यात्—प्लक्षन्यग्रोधखदिरपलाशा इति॥

(उद्द्योतः) भाष्ये—**द्वन्द्वेनेकग्रहणमित्युपलक्षणं** बहुव्रीहेरपि॥

(दूषणबाधकभाष्यम्)

नैष दोषः । अत्रापि द्वयोर्द्वयोः समासो भविष्यति ॥

(१२१६ दूषणसाधकवार्तिकम् ॥ २७ ॥)

॥ * ॥ द्वयोर्द्वयोः समास इति चेन्न बहुषु द्वित्वाभावात् ॥ * ॥

(व्याख्याभाष्यम्)

द्वयोर्द्वयोः समास इति चेत् । तन्न । किं कारणम्? । बहुषु द्वित्वाभावात् । न बहुषु द्वित्वमस्ति ॥

(प्रदीपः) बहुषु द्वित्वाभावादिति । ननु बहुषु द्वौ विद्येते । तद्यथा—एषां ब्राह्मणानां द्वावानयेति । तत्र बहुषूपक्रान्तेषु प्लक्षन्यग्रोधयोरेका द्वन्द्वसंज्ञा । खदिरपलाशयोर्द्वितीया । पुनर्द्वन्द्वसमुदायस्य तृतीया भविष्यति ॥ नैष दोषः । यद्यपि बहुषु द्वौ स्तस्तथापि चतुर्षु सहविवक्षितेषु एकैकस्य शब्दस्य चत्वारोर्था इति द्वयोश्चार्थे वृत्त्यसंभवात् समासभाक्त्वं नास्तीति एतदनेन प्रतिपाद्यते ॥

(उद्योतः) बहुषु द्वित्वाभावादिति । बहुषु बुद्धिस्थेषु तदवयवयोर्द्वित्वाभावादित्यर्थः । त्रिपुत्रे द्विपुत्रत्वव्यवहाराभावात् ॥ एवं च द्वयोः समास इति त्वदुक्तिरसंगतेति भावः ॥ ननु मास्तु तयोर्द्वित्वमन्यासंनिधाने यौ वस्तुतो द्वित्ववन्तौ तयोः समास इति तदर्थः । एवमेव शते पञ्चाशदित्युक्तिः । अन्यासंनिधाने ये पञ्चाशत्त्ववन्तस्ते शते सन्तीति तदर्थ इति शङ्कते—नन्विति ॥ समाधत्ते—यद्यपीति ॥ एकैकस्य चत्वार इति । अनेकस्य चार्थवृत्तित्वे समासविधानात् एकैकस्य चतुरवयवः समूहोर्थः । तत्र द्वयोः सत्त्वेपि तयोरितरद्वयसापेक्षतयाऽसामर्थ्यान्न तयोः समास इति भावः । बहुषु द्वित्वाभावात्तदन्तर्गतद्वयोस्तत्समनियतसामर्थ्याभावादिति भाष्यार्थः ॥

(आक्षेपबाधकभाष्यम्)

नावश्यमेवं विग्रहः कर्तव्यः—प्लक्षश्च न्यग्रोधश्च खदिरश्च पलाशश्चेति ॥ किं तर्हि? । एवं विग्रहः करिष्यते—प्लक्षश्च न्यग्रोधश्च प्लक्षन्यग्रोधौ, खदिरश्च पलाशश्च खदिरपलाशौ, प्लक्षन्यग्रोधौ च खदिरपलाशौ च प्लक्षन्यग्रोधखदिरपलाशा इति ॥

(प्रदीपः) एवं विग्रह इति । द्वयोर्द्वयोः सहविवक्षा भविष्यति न तु युगपच्चतुर्णामित्यर्थः ॥

(उद्योतः) द्वयोर्द्वयोः सहेति । अन्येषामबुद्धिस्थत्वान्न तयोः सापेक्षतेति भावः ॥

(आक्षेपसाधकभाष्यम्)

होतृपोतृनेष्टोद्गातारस्तर्हि न सिद्ध्यन्ति । होतापोतानेष्टोद्गातार इति प्राप्नोति ॥

(प्रदीपः) होतृपोतृनेष्टोद्गातार इति । यदा बहूनां समासस्तदा सर्वान्त उत्तरपदे परत एकस्यैवानङ् भविष्यति द्वयोर्द्वयोस्तु समासे क्रियमाणे एकं वर्जयित्वा सर्वेषामानङा भाव्यम् । अत्र च भाष्यकारवचनप्रामाण्यादुद्गातृशब्दस्य दीर्घः । अन्यथा नप्त्रादिग्रहणस्य नियमार्थत्वान्न स्यात् ॥

(उद्योतः) सर्वान्त इति । तत्समासीयसर्वान्त इत्यर्थः । तत्रैवोत्तरपदशब्दस्य रूढेरिति भावः ॥ नियमार्थत्वादिति । तृज्ग्रहणेनैव सिद्धे नप्त्रादिग्रहणमुणादिव्युत्पन्नानां चेन्नप्त्रादीनामेवेति नियमार्थमिति भावः ॥ अयमनौणादिकतृन्तृजन्यतरान्त इति भाष्याशयः ॥ इदं "ण्वुल्तृचौ" तृन्निति सूत्रस्थभाष्यविरुद्धम् ॥ भाष्ये—इति प्राप्नोतीत्यस्य इत्येव प्राप्नोतीत्यर्थः ॥

(प्रत्याक्षेपभाष्यम्)

न चैतदेवं भवितव्यम्? ॥

(प्रत्याक्षेपबाधकभाष्यम्)

भवितव्यं च, यदैवं विग्रहः क्रियते—होता च पोता च होतापोतारौ, नेष्टा चोद्गाता च नेष्टोद्गातारौ, होतापोतारौ च नेष्टोद्गातारौ च होतापोतानेष्टोद्गातार इति । होतृपोतृनेष्टोद्गातारस्तु न सिद्ध्यन्ति ॥

(१२१७ दूषणान्तरवार्तिकम् ॥ २८ ॥)

॥ * ॥ समासान्तप्रतिषेधश्च ॥ * ॥

(व्याख्याभाष्यम्)

समासान्तस्य च प्रतिषेधो वक्तव्यः । वाक्त्वक्स्रुग्दृषदमिति । वाक्त्वचस्रुग्दृषदमिति प्राप्नोति ॥

(प्रदीपः) समासान्तप्रतिषेधश्चेति । द्वयोर्द्वयोर्द्वन्द्वसंज्ञायां प्रतिद्वन्द्वं समासान्तः प्राप्नोतीत्यर्थः ॥ यद्यपि प्रक्रियान्तरे प्रतिद्वन्द्वमानङादेशवत् समासान्तेन भाव्यम् । तथापि बहूनां समासाभावादेकसमासान्तता न कदाचित् प्राप्नोति इति चोद्यते ॥

(उद्योतः) समासान्तेन भाव्यमिति । तथा च तस्येष्टतया तत्प्रतिषेधारम्भोनर्थक इति भावः ॥

(आक्षेपबाधकभाष्यम्)

नैष दोषः । अत्रापि परेण सह समासो भविष्यति । स्रुक्च दृषच्च स्रुग्दृषदं त्वक् च स्रुग्दृषदं च त्वक्स्रुग्दृषदम् । वाक् च त्वक्स्रुग्दृषदं च वाक्त्वक्स्रुग्दृषदमिति ॥

(प्रथमाक्षेपदार्ढ्यभाष्यम्)

होतृपोतृनेष्टोद्गातार एव तर्हि न सिद्ध्यन्ति ॥

(आक्षेपान्तरभाष्यम्)

इह च—

"सुसूक्ष्मजटकेशेन सुनताजिनवाससा ।
समन्तशितिरन्ध्रेण द्वयोर्वृत्तौ न सिद्ध्यति ॥

(प्रदीपः) **सुसूक्ष्मजटकेशेनेति** । सुष्ठु सूक्ष्मा जटाः केशा अस्येति विग्रहः । यद्यनेकग्रहणं न क्रियते, क्रियमाणं वोपसर्जनसंज्ञार्थं विज्ञायते, सुप्सुपेति चानुवर्तते, तदात्र बहूनां बहुव्रीहिर्न प्राप्नोति ॥

(उद्द्योतः) **सुष्ठुसूक्ष्मा इति** । भाष्यप्रामाण्याज्जटशब्दोऽदन्तः पुलिङ्गो घनपर्यायो जटापर्यायो वा । संज्ञाछन्दसोरभावेपि सूक्ष्मशब्दस्योत्तरपदपरत्वाभावे बहुलग्रहणादुभयत्रापि ह्रस्व इति कश्चित् । तन्न, ङ्वेचेत्यस्य वैयर्थ्यापत्तेः ॥ एतेन **पलयो गर्भिणय** इत्यादावनुत्तरपदेपि बहुलग्रहणादनेन ह्रस्व इति हरदत्तोक्तमपास्तम् ॥ **अम्ब्यार्थैनिगमे अवश्यं छन्दसि ह्रस्वत्वं वक्तव्यं पलयो गर्भिणय** इत्यर्थमिति भाष्यमुपादाय **व्यत्ययो बहुल**मिति दीर्घस्य ह्रस्व इति कैयटोक्तेश्च । यद्यपि पूर्वपूर्वं कर्मधारयं कृत्वा बहुव्रीहिः क्रियते तथापि सुशब्दस्वरो न सिध्यतीत्यर्थः । यद्यपि सूक्ष्मा जटाः सूक्ष्मजटाः तादृशाश्च ते केशाश्च सूक्ष्मजटकेशाः सुष्ठु सूक्ष्मजटकेशा यस्येति बहुव्रीहौ द्विपदसमासेपि सिध्यति स्वरश्च, तथापि अत्र पक्षे सौष्ठवस्य शब्दमर्यादया सूक्ष्मविशेषणता न लभ्येतेति अनेकपद एव स एष्टव्यः । **नञ्सुभ्या**मित्युत्तरपदान्तोदात्तत्वापत्त्या स्वरासिद्धेश्च । इष्यते तु पूर्वपदप्रकृतिस्वरेण सुशब्दस्वर इति दिक् ॥

(द्वितीयपक्षाभ्युपगमभाष्यम्)

अस्तु तर्ह्यविशेषेण ॥

(उद्द्योतः) भाष्ये—अस्तुतर्हीति । द्वन्द्वादिविधायकयोरनेकग्रहणसामर्थ्यात् । सुविलेव वर्तते सुपेति निवृत्तमिति भावः ॥

(१२१८ आक्षेपवार्तिकम् ॥ २९ ॥)

॥*॥ अविशेषेण बहुव्रीहावनेकपदप्रसङ्गः [तत्र स्वरसमासान्तपुंवद्भावेषु दोषः]॥*॥

(भाष्यम्) **यद्यविशेषेण बहुव्रीहावनेकपदप्रसङ्गः ॥ तत्र को दोषः ? । तत्र स्वरसमासान्तपुंवद्भावेषु दोषः । तत्र स्वरसमासान्तपुंवद्भावेषु दोषो भवति । स्वर—पूर्वशालाप्रियः अपरशालाप्रियः । स्वर ॥ समासान्त—पञ्चगवप्रियः पञ्चनावप्रियः । समासान्त ॥ पुंवद्भाव—खादिरेतरशाम्यम् ॥**

(प्रदीपः) **पूर्वशालाप्रिय इति** । यदा बहूनां बहुव्रीहिसंज्ञा, तदा पूर्वपदप्रकृतिस्वरेण पूर्वशब्दः **स्वाङ्गशिटामदन्ताना**मित्याद्युदात्तः स्याद्, यदा तु द्वयोरेव बहुव्रीहिसंज्ञा भवतीति पक्षः तदा पूर्वा शाला पूर्वशालेति **पूर्वापरप्रथमे**ति समासे कृते समासान्तोदात्तत्वे च पूर्वशाला प्रियास्येति द्विपदे बहुव्रीहौ कृते पूर्वपदप्रकृतिस्वरेण शालाशब्दाकार उदात्तः सिध्यति ॥ ननु त्रिपदे बहुव्रीहौ कृते **तद्धितार्थोत्तरपदे**ति तत्पुरुषेणात्र भाव्यमिति कथं दोषोपन्यासः । एवं तर्हि परस्तादयं परिहारो वक्ष्यत इति न तावदत्राश्रितः ॥ **पञ्चगवप्रिय इति** । त्रिपदे बहुव्रीहौ समासान्तो न प्राप्नोति । यदा द्वयोर्बहुव्रीहिरिति पक्षस्तदा पञ्चानां गवां समाहारः पञ्चगवं तत् प्रियमस्येति रूपं सिध्यति । **खादिरेतरशाम्यमिति** । खादिरी इतरा शम्यास्येति त्रिपदे बहुव्रीहौ क्रियमाणे उत्तरपदे पुंवद्भावो विधीयमानः खादिरीशब्दस्य न प्राप्नोति । यदा तु द्वयोर्बहुव्रीहिरिति पक्षस्तदेतरा शम्या इतरशम्येति समासे कृते खादिरी इतरशम्याऽस्येति बहुव्रीहौ सिध्यति पुंवद्भावः ॥

(उद्द्योतः) **अनेकपदप्रसङ्ग इति** । अनेकपदसमासत्वप्रयुक्तदोषप्रसङ्ग इत्यर्थः ॥ **समासान्तइति** । **गोरतद्धिते**ति टच् ॥ **पञ्चगवमिति** । टचः समासभक्तत्वेनाकारान्तोत्तरपदत्वाभावात् स्त्रीत्वाभावः ॥ **तदेतराशम्येति** । पूर्वं कर्मधारयगर्भस्तु न कृतः इतरशब्दस्य पूर्वनिपातापत्तेः । एवं च भाष्ये पुंवद्भाव इति दोषोपलक्षणम्—इतराशब्दस्य पूर्वनिपातापत्तिरपि दोषो बोध्यः । शम्यापेक्षया द्वयोर्विशेषणत्वेपि प्रथमानिर्दिष्टत्वेपि इतरा इत्यस्य सर्वनामत्वादिति वदन्ति ॥

(१२१९ समाधानवार्तिकम् ॥ ३० ॥)

॥ * ॥ न वावयवतत्पुरुषत्वात् ॥ * ॥

(व्याख्यभाष्यम्)

न वा एष दोषः । किं कारणम् । अवयवतत्पुरुषत्वात् । अवयवोत्र तत्पुरुषसंज्ञः, तदाश्रयौ समासान्तपुंवद्भावौ भविष्यतः ॥

(प्रदीपः) **न वेति** । क्वचित् त्रयाणां पदानां बहुव्रीहौ कृते द्वयोः पदयोस्**तद्धितार्थोत्तरपदे**ति तत्पुरुषः । भिन्नविषयत्वाच्च बहुव्रीहितत्पुरुषसंज्ञयोरेकसंज्ञाधिकारेपि नास्ति विरोधः । खादिरेतरशम्यमित्यत्र पुंवद्भावसिद्धये कृते तत्पुरुषे खादिरी इतरशम्यास्येति द्विपदो बहुव्रीहिः क्रियते न तु त्रिपदः । विकारे च प्रत्ययविधानाद् **वृद्धिनिमित्तस्येति** प्रतिषेधो नास्ति ॥

(उद्द्योतः) क्वचिद् बहुव्रीहौ कृते तत्पुरुषः, क्वचित्तत्पुरुषे बहुव्रीहिरिति विषयविवेकं दर्शयति—**क्वचिदिति** ॥ आकडारीयत्वात् बहुव्रीहितत्पुरुषयोः कथं समावेश इत्यत आह—**भिन्नेति** । एका समुदायस्था पराऽवयवस्येति भिन्नविषयत्वमिति भावः ॥

(आक्षेपभाष्यम्)

स्वरः कथम् ? ॥

(प्रदीपः) **स्वरः कथमिति** । पूर्वशालाप्रिय इत्यादावपवादत्वाद् बहुव्रीहिस्वरः प्राप्नोति ॥

(१२२० समाधानवार्तिकम् ॥ ३१ ॥)

॥ * ॥ तस्यान्तोदात्तत्वं विप्रतिषेधात् ॥

(व्याख्याभाष्यम्)

अन्तोदात्तत्वं क्रियतां पूर्वपदप्रकृतिस्वर इति। अन्तोदात्तत्वं भवति विप्रतिषेधेन ॥

(प्रदीपः) **विप्रतिषेधादिति** । विरोधमात्रं विप्रतिषेधशब्देनात्रोच्यते । हेतुस्त्वन्तरङ्गत्वं निमित्तिस्वरबलीयस्त्वं च ॥

(समाधानबाधकभाष्यम्)

नैष युक्तो विप्रतिषेधः । 'विप्रतिषेधे परम्' इत्युच्यते । पूर्वं चान्तोदात्तत्वम्, परं पूर्वपदप्रकृतिस्वरत्वम् ॥

(प्रदीपः) इतरस्तु विप्रतिषेधमूलं परत्वमनेन हेतुत्वेनोक्तमिति मत्वाह—**नैष युक्त इति** ॥

(समाधानाभिप्रायभाष्यम्)

न परविप्रतिषेधं ब्रूमः ॥ किं तर्हि ? ॥ अन्तरङ्गविप्रतिषेधम् ॥

(प्रदीपः) **अन्तरङ्गेति । अनुदात्तं पदमेकवर्जमिति** वचनाद् द्वयोः स्वरयोरसंभवात् कक्ष्यान्तरप्राप्तत्वाच्च बाध्यबाधकभावाभावादवयवाश्रयत्वादन्तरङ्गत्वं व्यवस्थाहेतुराश्रीयत इत्यर्थः ॥

(उद्योतः) भाष्ये—**अन्तरङ्गविप्रतिषेधमिति** । अन्तरङ्गत्वलक्षणविरोधमित्यर्थः ॥ ननु द्वयोरपि संभवे कथं विरोधोत आह—**अनुदात्तं पदमिति** ॥ नन्वन्तोदात्तं प्रति बहुव्रीहिस्वरस्यापवादत्वात् कथमन्तरङ्गत्वं तत्राह—**कक्षान्तरेति** । बहुव्रीह्यनन्तरभावित्वात्तत्पुरुषस्य तत्स्वरस्य समासान्तरप्राप्तत्वरूपं कक्षान्तरप्राप्तत्वम् । एवं च बहुव्रीहिगतसमासत्वप्रयुक्तान्तोदात्तत्वस्यैवापवादोयम्, न तु पश्चात्प्राप्ततत्पुरुषप्रयुक्तस्येत्यर्थः । 'अपवादोपि यद्यन्यत्र' इतिन्यायादिति भावः ॥ **अन्तरङ्गत्वमिति** । समासद्वये कृते तदनन्तरं स्वरद्वयप्रवृत्तिरित्यभिमानः ॥ वास्तवसमाधानं तु सतिशिष्टस्वरबलीयस्त्वमेव ॥ तदेव शब्दान्तरेण पठितं **निमित्तिस्वरेति** ॥

(१२२१ समाधानहेत्वन्तरवार्तिकम् ॥ ३२ ॥)

॥ * ॥ निमित्तिस्वरबलीयस्त्वाद्वा ॥ * ॥

(व्याख्याभाष्यम्)

अथ वा निमित्तस्वरान्निमित्तिस्वरो बलीयानिति वक्तव्यम् ॥ किं पुनर्निमित्तम्, को वा निमित्ती ? । बहुव्रीहिर्निमित्तम्, तत्पुरुषो निमित्ती ॥

(प्रदीपः) अन्तरङ्गोपि सतिशिष्टेन बहिरङ्गेणापि स्वरेण बाध्यत इत्यनैकान्तिकमन्तरङ्गत्वं मत्वा हेत्वन्तरमाह—**निमित्तिस्वरबलीयस्त्वादिति** । सति बहुव्रीहौ तदवयवोत्तरपदाश्रयो द्वयोस्तत्पुरुष इति बहुव्रीहेर्निमित्तत्वम् ॥

(उद्योतः) **अनेकान्तिकमिति** । पूर्वमेव बहुव्रीहिस्वरप्रवृत्त्या युगपत्प्राप्त्यभावेनान्तरङ्गपरिभाषाविषयाभाव इत्यत्र तात्पर्यमस्य बोध्यम् ॥

(आक्षेपभाष्यम्)

तत्तर्हि वक्तव्यम्—निमित्तस्वरान्निमित्तिस्वरो बलीयानिति ? ॥

(समाधानभाष्यम्)

न वक्तव्यम् ।

(१२२२ समाधानसाधकवार्तिकम् ॥ ३३ ॥

॥ * ॥ एकशितिपात्स्वरवचनं तु ज्ञापकं निमित्तिस्वरबलीयस्त्वस्य ॥ * ॥

(व्याख्याभाष्यम्)

यदयं युक्तारोह्यादिष्वेकशितिपाच्छब्दं पठति तज्ज्ञापयत्याचार्यो निमित्तस्वरान्निमित्तिस्वरो बलीयानिति ॥

(प्रदीपः) **एकशितिपादिति** । युक्तारोह्यादिषु पूर्वपदाद्युदात्तार्थः पाठः । एकशब्दश्च कन्नन्तत्वात् **स्वाङ्गशिटामिति** वाद्युदात्तः । तत्र त्रिपदे बहुव्रीहौ कृते द्वयोश्च तत्पुरुषे **बहुव्रीहौ प्रकृत्येति** सिद्ध आद्युदात्तत्वे ज्ञापनार्थः पाठः संपद्यते ॥

(उद्योतः) **स्वाङ्गशिटामिति** । इदमव्युत्पत्तिपक्षे बोध्यम् ॥ **द्वयोस्तत्पुरुषे इति** । तद्धितार्थोत्तरपदेत्यनेनेत्यर्थः ॥

(ज्ञापकत्वनिरासभाष्यम्)

कः पुनरर्हति युक्तारोह्यादिष्वेकशितिपाच्छब्दं पठितुम् । एवं किल नाम पठ्यते—एकः शितिः एकशितिः, एकशितिः पादो यस्येति । तच्च न । एवं विग्रहः करिष्यते—एकः शितिरेषु त इमे एकशितयः, एकशितयः पादा यस्येति एकशितिपादिति ॥ अथाप्येवं विग्रहः क्रियते—एकः शितिरेकशितिः, एकशितिः पादो यस्येति, एवमपि नार्थः पाठेन । "इगन्ते द्विगौ" इत्येष स्वरोत्र बाधको भविष्यति ॥

(प्रदीपः) **कः पुनरिति** । सर्वथा स्वरस्य सिद्धत्वादकर्तव्य एव पाठो न ज्ञापक इत्यर्थः । निमित्तिस्वरस्य तु बलीयस्त्वं वाचनिकं न तु ज्ञापकसिद्धम् ॥

(उद्योतः) आचार्येण पठिते कथं पाठाभाव उक्त इत्यतस्तात्पर्यमाह—**सर्वथेति** । विग्रहद्वयेपीत्यर्थः ॥ भाष्ये—**एवं किल नामेति** । तत्पुरुषपूर्वपदकबहुव्रीहौ तिकारस्योदात्तत्वं प्राप्तं तद्बाधेनैकारोदात्तत्वाय स शब्दः पठ्येतेत्यर्थः । तच्च न युक्तम् । विग्र-

हणान्तरकरणात् ॥ तत्पुरुषपूर्वपदकबहुव्रीहावपि तद्धितार्थेति तत्पुरुषसमाससंज्ञायां द्विगुत्वमित्याशयेन भाष्ये आह—इगन्ते द्विगाविति । पूर्वपदप्रकृतिस्वरविधायकमेतत् ॥

(आक्षेपान्तरभाष्यम्)

अस्य तर्हि बहुव्रीह्यवयवस्य तत्पुरुषसंज्ञा प्राप्नोति—

सुसूक्ष्मजटकेशेन सुनताजिनवाससा ।

समन्तशितिरन्ध्रेणेति ।

तत्र को दोषः? ॥ *तस्यान्तोदात्तत्वं विप्रतिषेधात्* इत्यन्तोदात्तत्वं स्याद्विप्रतिषेधेन ॥

(उद्द्योतः) अवयवस्य तत्पुरुषसंज्ञा वाचनिक्यनेन कृतेति मत्वाह—अस्य तर्हीत्यादि ॥

(समाधानभाष्यम्)

नैष दोषः । नेदं बहुव्रीह्यवयवस्य तत्पुरुषस्य लक्षणमारभ्यते॥ किं तर्हि? । यस्य बहुव्रीह्यवयवस्य तत्पुरुषस्य तल्लक्षणमस्ति तस्यान्तोदात्तत्वं भविष्यति विप्रतिषेधेन ॥

(प्रदीपः) नेदमिति । यद्यपूर्ववचनं क्रियेत—बहुव्रीह्यवयवस्तत्पुरुषो भवतीति, ततोत्र स्याद्दोषः । दिक्संख्ययोस्तूत्तरपदे तत्पुरुषो विधीयत इति दोषाभावः ॥

(उद्द्योतः) भाष्ये—नेदमिति । न वावयवतत्पुरुषत्वादित्येतत् ॥

(आक्षेपभाष्यम्)

ननु चास्याप्यस्ति ॥ किम्? । "विशेषणं विशेष्येण बहुलम्" इति ॥

(समाधानभाष्यम्)

बहुलवचनान्न भविष्यति ॥

(प्रदीपः) बहुलवचनादिति । समुदायस्य वृत्ताववयवस्यान्या संज्ञा विशेषलक्षणं विना बहुलवचनान्न प्रवर्तते ॥

(उद्द्योतः) बहुलवचनादिति । कचिदन्यदेवेत्यर्थकादित्यर्थः। अनेन चैतत्प्रपञ्चभूतानां पूर्वनिपातनियमार्थानां च बहुलग्रहणेन निवृत्तिरिति सूच्यते । अन्यथा तेषां तत्त्वं भज्येत ॥ एतेन महत्कष्टं श्रित इति प्रतीकस्यत्रयाणां तत्पुरुषे सन्महदिति द्वयोः समासपरः कैयटः परास्तः । न च त्रयाणामेकार्थीभावेपि द्वयोर्निष्कृष्यैकार्थीभावाभावात्कथं विशेषणमित्यस्य प्राप्तिः, तद्धितार्थेति तु सामर्थ्यात् प्रवर्तत इति वाच्यम् । निष्कृष्यैकार्थीभाव एव शास्त्रप्रवृत्तिरित्यर्थे मानाभावादिति दिक् ॥ विशेषलक्षणं विनेति । तच्च तद्धितार्थेत्यादि ॥

(आक्षेपान्तरभाष्यम्)

अस्य तर्हि बहुव्रीह्यवयवस्य तत्पुरुषसंज्ञा प्राप्नोति—अधिकषष्टिवर्ष इति ॥ तत्र को दोषः? । * तस्यान्तोदात्तत्वं विप्रतिषेधात् * इत्यन्तोदात्तत्वं स्याद्विप्रतिषेधेन ॥

(प्रदीपः) अधिकषष्टिवर्ष इति । त्रिपदे बहुव्रीहौ कृते अधिकग्रहणं चालुकीत्यधिकशब्दस्य संख्यासंज्ञात्वात्तद्धितार्थोत्तरपदेति पदद्वयस्य तत्पुरुषे कृते समासान्तोदात्तत्वं प्राप्नोतीत्यर्थः । अधिकशब्दः कन्नन्तत्वादाद्युदात्तः ।

(उद्द्योतः) विशेषलक्षणाभावोऽत्रापि तुल्य इत्यत आह—अधिकग्रहणं चेति ॥

(आक्षेपबाधकभाष्यम्)

नैष दोषः । "इगन्ते द्विगौ" इत्येष स्वरो बाधको भविष्यति ॥

(आक्षेपान्तरभाष्यम्)

यस्तर्हि नेगन्तः— अधिकशतवर्ष इति ॥

(प्रागुक्ताक्षेपस्यापि समञ्जसत्वभाष्यम्)

इह चाप्यधिकषष्टिवर्ष इति समासान्तः प्राप्नोति *डचः प्रकरणे संख्यायास्तत्पुरुषस्योपसंख्यानं निस्त्रिंशाद्यर्थम्* इति ॥

(आक्षेपबाधकभाष्यम्)

नैष दोषः । अव्ययादेरित्येवं तत् ॥

(आक्षेपभाष्यम्)

किं पुनः कारणम्—अव्ययादेरित्येवं तत्? ।

(समाधानभाष्यम्)

इह मा भूद्—गोत्रिंशद्, गोचत्वारिंशदिति ॥

(आक्षेपभाष्यम्)

बहुव्रीहिसंज्ञा तर्हि प्राप्नोति "संख्ययाव्ययासन्नादूराधिकसंख्याः संख्येये" इति ॥

(प्रदीपः) बहुव्रीहिसंज्ञा तर्हीति । अधिकषष्टिवर्षेपि दोष इति भावः । त्रिपदे बहुव्रीहौ कृते पदद्वयस्य तद्धितार्थोत्तरपदेति तत्पुरुषं परत्वाद् बाधित्वा संख्ययाव्ययेति बहुव्रीहिः प्राप्नोति । ततश्च बहुव्रीहौ संख्येय इति डच्प्रसङ्गः ॥

(उद्द्योतः) अधिकषष्टिवर्षेपीति । अधिकशतवर्षेपि डचः प्राप्त्या स्वरे विशेष इति भावः ॥

(समाधानभाष्यम्)

न संख्यां संख्येये वर्तयिष्यामः ॥ कथम्? । एवं विग्रहः करिष्यते—अधिका षष्टिर्वर्षाणामस्येति ॥

(प्रदीपः) न संख्यामिति । अधिकषष्टिवर्ष इत्येव यथा स्यादित्येवमर्थमव्यविकन्याय आश्रीयते । तेनाधिका षष्टिर्वर्षाण्यस्येति वाक्यमेव भवति ॥

(उद्द्योतः) संख्येयपरेण बहुव्रीहौ दोषः स्यादेवेत्यत आह—**अधीति** ॥ षष्टिशब्दस्याजहल्लिङ्गत्वमेकवचनान्तत्वं च मत्वाह—**अधिकाषष्टिर्वर्षाण्यस्येति । अधिकाषष्टिर्वर्षाणामिति** ॥

(आक्षेपसाधकभाष्यम्)

यथा तर्हि स योगः प्रत्याख्यायते तथा पूर्वेण प्राप्नोति ॥ कथं च स योगः प्रत्याख्यायते? । *अशिष्यः संख्योत्तरपदः संख्येयाथाभिधायित्वात्* इति ॥ प्रत्याख्याते तस्मिन्योगे संख्यां संख्येये वर्तयिष्यामः । तत्रैवं विग्रहः करिष्यते—अधिका षष्टिर्वर्षाण्यस्येति । सर्वथा वयमधिकषष्टवर्षान्न मुच्यामहे ॥ कथम्? । यावता स योगः प्रत्याख्यायते । अयं च विग्रहोस्ति—अधिका षष्टिर्वर्षाणामस्येति ।

(प्रदीपः) **पूर्वेणेति** । अधिका षष्टिर्येषां वर्षाणामिति वर्षेषु संख्येयेषु **अनेकमन्यपदार्थे** इति बहुव्रीहिः प्राप्नोति । संख्येयवृत्तित्वाच्च बहुव्रीहेस्तन्निबन्धनो डजपीति दोषः । बहुव्रीहिगर्भेश्च पुनर्वयस्यन्यभिधेये बहुव्रीहिः प्राप्नोति ॥ **प्रत्याख्यात इति** । अव्यविकन्यायेन चाधिका षष्टिर्वर्षाणामस्येति वाक्यमेव भविष्यति ॥ अव्यविकन्यायममत्वाह—**सर्वथेति** ।

(उद्द्योतः) यद्यपि अधिका षष्टिर्येषां वर्षाणामिति विग्रहे स्थितेपि संख्ययेतिमन्त्र पूर्वेण बहुव्रीहिः प्राप्नोतीति वक्तुं शक्यते, तथापि संख्येये संख्याया अवृत्त्या डचोप्राप्त्या प्रयोजनाभाव इति वक्तुं शक्यमित्याशयेन भाष्ये—'**यथा तर्हि स योगः प्रत्याख्यायते तथा पूर्वेणे**त्युक्तम् ॥ **यदा तदे**ति क्वचित् पाठः ॥ **स योगः संख्याऽव्ययेति**योगः ॥ **डजपीति** । तत्प्रत्याख्याने संख्येये वर्तमानबहुव्रीहेरित्यर्थात्स्यादेव डजिति भावः ॥ तर्हि वर्षोत्तरपदत्वं कथं तत्राह—**बहुव्रीहिगर्भे इति** । एवं चाधिकषष्टवर्ष इति प्रयोगो दुर्वार एवाधिकषष्टिर्वर्षाण्यस्येति विग्रहे वाक्याङ्गीकारेपीति भावः ॥ तत्खण्डयति—भाष्ये—**प्रत्याख्याते तस्मिन्निति** ॥ **अधिका षष्टिर्वर्षाण्यस्येति** । अत्रावान्तरबहुव्रीहिस्तु न, संख्येयरूपान्यपदार्थाभावादिति भावः ॥ नन्वधिका षष्टिर्येषां वर्षाणामित्यस्यापि विद्यमानत्वात्कथं दोषपरिहार इत्यत आह—**अव्यविकेति** ॥ यथाश्रुतग्राहिणश्चोद्यमित्याह—**अव्यविकन्यायममत्वाहेति** ॥ भाष्ये—**अधिकषष्टवर्षान्न मुच्यामह** इति पाठः । ईदृशानिष्टरूपादित्यर्थः । क्वचित्त्वधिक**षष्टिवर्षान्न मुच्यामहे** इति पाठः । तदाऽधिकषष्टिवर्षविषयादनिष्टरूपान्न मुच्यामह इति अर्थः ॥ **अधिका षष्टिर्वर्षाणामस्येति** । अधिका षष्टिर्येषां वर्षाणां तानि अस्येत्यर्थः ॥

(आक्षेपबाधकभाष्यम्)

यत्तु तदुक्तम्—अधिकषष्टिवर्षो न सिद्ध्यतीति, स सिद्धो भवति ॥ कथम्? । यावता स योगः प्रत्याख्यायते । अयं च विग्रहोस्ति—अधिका षष्टिर्वर्षाण्यस्येति ॥

(प्रदीपः) अव्यविकन्यायाश्रयेणाह—**यत्तु तदुक्तमिति** । वृत्तिविषये दशादीनामपि **द्व्येकयोरिति निर्देशात्** संख्यानमात्रवृत्तित्वात् संख्येयस्यान्यपदार्थत्वात् स योगः प्रत्याख्यायते ॥

(उद्द्योतः) **आदशभ्यः संख्याः संख्येय** इति नियमात्तद्विषये सूत्रस्यावश्यकत्वात्कथं प्रत्याख्यानं तत्राह—**वृत्तिविषय इति** । अधिका षष्टिर्वर्षाण्यस्येति विग्रहेवान्तरान्यपदार्थाभावादनेकमित्यस्याप्राप्तौ तद्योगप्रत्याख्यानेऽधिकषष्टिवर्षः सिद्धः । विग्रहान्तरे तु वाक्यमेव । एवं सूत्रारम्भे अधिका षष्टिर्वर्षाणामस्येति बहुव्रीहिगर्भे बहुव्रीहौ संख्येये वर्तमानसंख्यान्तबहुव्रीहेरित्यर्थान्न डच् । विग्रहान्तरे तु वाक्यमेवेत्यधिकषष्टिवर्षः सिद्ध इति भाष्याशयः ॥

(आक्षेपभाष्यम्)

अधिकशतवर्षस्तु न सिद्ध्यति ॥

(प्रदीपः) **अधिकशतवर्षस्त्विति** । अधिकं शतं वर्षाण्यस्येति त्रिपदे बहुव्रीहौ कृते **तद्धितार्थोत्तरपदेति** तत्पुरुषे समासान्तोदात्तत्वं प्राप्नोति, आद्युदात्तत्वं चेष्यते ॥

(समाधानभाष्यम्)

कर्तव्योत्र यत्नः ॥ समर्थः पदविधिः ॥ १ ॥

इति श्रीमहाभाष्ये द्वितीयाध्यायस्य प्रथमे पादे प्रथममाह्निकम् ॥

(प्रदीपः) **कर्तव्योत्र यत्न इति** । युक्तारोह्यादिष्वधिकशतवर्षशब्द आद्युदात्तार्थो द्रष्टव्यः ॥ १ ॥

इत्युपाध्यायजैयटपुत्रकैयटकृते महाभाष्यप्रदीपे द्वितीयस्याध्यायस्य प्रथमे पादे प्रथममाह्निकम् ॥

(उद्द्योतः) एवं च द्वन्द्वबहुव्रीहिविषयेऽविशेषेणेति पक्षः स्थितः ॥ १ ॥

इति शिवभट्टसुतसतीगर्भजनागेशभट्टविरचिते व्याकरणभाष्यप्रदीपोद्द्योते द्वितीयाध्यायस्य प्रथमे पादे प्रथममाह्निकम् ॥

द्वितीयाध्याये प्रथमपादे द्वितीयमाह्निकम् ॥

(२२२ अतिदेशसूत्रम् ॥ २।१।२ आ. १ सूत्रम्)

३५१ सुबामन्त्रिते पराङ्गवत्स्वरे ॥ १।२॥

(सुब्ग्रहणप्रयोजनाधिकरणम्)

(आक्षेपभाष्यम्)

सुबिति किमर्थम्? ॥

(प्रदीपः) **सुबामन्त्रिते पराङ्गवत् ॥ २ ॥ सुबिति किमर्थमिति** । आमन्त्रितस्य पदत्वात्तस्मिन् परतो विधीयमानस्य पराङ्गवद्भावस्य पदविधित्वात् **समर्थपरिभाषो**पस्थानात्तिङन्तस्य न भविष्यति । **तथा हि** । व्यधिकरणस्य

तिङन्तस्य वास्तवसामर्थ्ये समानाधिकरणस्य वाचनिकम्, अतिव्याप्तिनिवारणार्थमवश्यं कर्तव्यं **षष्ठ्यामन्त्रितकारकवचनमिति** तेनैव तिङन्तस्य सिद्धो निरासः । क्रियमाणे च सुब्ग्रहणे तीक्ष्णया सूच्या सीव्यन्नित्यादौ सुबन्तसमुदायस्याप्राप्तिरित्यव्याप्तिः प्राप्नोतीति भावः ॥

(उद्द्योतः) **सुबामन्त्रिते ॥ २ ॥ व्यधिकरणस्येति** । उपात्तामन्त्रितानन्वयिन इत्यर्थः । यथा हे पीड्यमान त्वं शृणु अहं पीड्ये इत्यर्थक पीड्ये पीड्यमानेत्यादाविति भावः ॥ **वाचनिकमिति । समानाधिकरणमसमर्थवदिति** ॥ युक्त्यन्तरमप्याह—**अतव्याप्तीति** । क्षत्रेणाग्ने इत्यादाविति भावः । भाष्यास्वाप एव प्रश्नाशय उपलभ्यते ॥ **सुबन्तसमुदायस्येति** । तस्यासुबन्तत्वादिति भावः ॥

(समाधानभाष्यम्)

करोष्यटन् ॥

(प्रदीपः) **करोष्यटन्निति । अधात्वभिहितमिति** सापवादत्वान्नास्ति वाचनिकमसामर्थ्यम् ॥

(समाधानबाधकभाष्यम्)

नैतदस्ति । असामर्थ्यादत्र न भविष्यति॥ कथमसामर्थ्यम्?। समानाधिकरणमसमर्थवद्भवतीति॥

(उद्द्योतः) भाष्ये—**नैतदस्तीति** । शङ्किता। **नैष दोषोऽधात्वभिहितमिति** च सिद्धान्त्येकदेशीति तत्त्वम् ॥ एकार्थीभावसामर्थ्यस्यैव तत्र सूत्रे ग्रहणेन तस्यात्रानुपस्थितेरित्याहुः ॥

(समाधानभाष्यम्)

इदं तर्हि—पीड्ये पीड्यमानेति ॥

(प्रदीपः) **पीड्ये पीड्यमानेति** । हे पीड्यमान त्वदीयया पीडयाऽहं पीड्य इत्यस्ति सामर्थ्यम् । अथ वा संबोधनपदं क्रियाया एव विशेषकमित्यस्ति सामर्थ्यम् । तथा च—व्रजानि देवदत्तेति निघातो भवति । पीड्य इति **तास्यनुदात्तेद्विति** लसार्वधातुकस्यानुदात्तत्वम्, यक उदात्तत्वा**देकादेश उदात्तेनोदात्त** इत्येकार उदात्तः । पीड्यमानेत्यस्य पदादुत्तरस्य निघातः ॥

(उद्द्योतः) तिङन्तामन्त्रितयोः परस्परसंबन्धाभावादसामर्थ्यमित्यत आह—**त्वदीययेति** । पीड्यमानपदार्थविशेषणीभूतपीडाकरणकत्वेन तद्द्वारा सामर्थ्यमिति भावः ॥ साक्षादपि सामर्थ्यं दर्शयितुमाह—**अथवेति** ॥ **तथा च व्रजानीति** । वस्तुतः साक्षात्परस्परान्वयाभावेपि नद्यास्तिष्ठति कूले इत्यादाविव निघातसिद्धिरत्रास्त्येवेति बोध्यम् ॥ **एकार उदात्त इति** । पराङ्गवद्भावे तु पीड्ये इति पीकारेकार उदात्तः स्यादिति भावः ॥

(पूर्वोक्तसमाधानसाधकभाष्यम्)

इदं चाप्युदाहरणम्—करोष्यटन् ॥

(आक्षेपबाधकस्मारणभाष्यम्)

ननु चोक्तम्—असामर्थ्यादत्र न भविष्यतीति । कथमसामर्थ्यम्? । समानाधिकरणमसमर्थवद्भवतीति ॥

(समाधानभाष्यम्)

नैष दोषः । अधात्वभिहितमित्येवं तत् ॥

(प्रदीपः) **अधात्वभिहितमिति । सर्वं नाम धातुजमिति** दर्शनेन सर्पिःकालकमिति यद्यपि धात्वभिहितं तथापि यत्र क्रिया प्रवृत्तिनिमित्तं स्फुटा च धातुप्रत्ययेन कर्त्रादिप्रतिपत्तिस्तद्धात्वभिहितं गृह्यते ॥ यदप्युक्तं वचनान्तरेणातिव्याप्तिर्वार्यत इति । तदपि न युक्तम् । नहि सूत्रकारो वार्तिककारस्य वचनेनातिव्याप्तिनिवारणं मन्यते ॥

(उद्द्योतः) **स्फुटा चेति** । क्रियाप्रवृत्तिनिमित्तकत्वे हि सा स्फुटा भवतीति बोध्यम् ॥ **मन्यत इति** । अग्रे वार्तिकस्य वक्ष्यमाणतयात्र पूर्वपक्षिसिद्धान्त्येकदेशिनोस्तदज्ञानाच्चेत्यपि बोध्यम् ॥ एतेन वार्तिकानामपि वाक्यैकदेशन्यायेन सूत्रतात्पर्यविषयतायाः परपशायां भाष्ये ध्वनितत्वेनेदं चिन्त्यमित्यपास्तम् ॥

(पराङ्गवद्भावविषयनिर्णयाधिकरणम्)

(१२२३ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ आमन्त्रितस्य पराङ्गवद्भावे षष्ठ्यामन्त्रितकारकवचनम् ॥ * ॥

(व्याख्याभाष्यम्)

आमन्त्रितस्य पराङ्गवद्भावे षष्ठ्यन्तमामन्त्रितकारकं पराङ्गवद्भवतीति वक्तव्यम् । षष्ठ्यन्तं तावत्—मद्राणां राजन्, मगधानां राजन् ॥ आमन्त्रितकारकम्—कुण्डेनाटन् ॥

(प्रदीपः) **आमन्त्रितस्येति** । आमन्त्रिते यो विधीयते स आमन्त्रितसंबन्धी भवतीति षष्ठीनिर्देशः ॥ **आमन्त्रितकारकमिति** । आमन्त्रिते या धातुवाच्या क्रिया तस्याः कारकमित्यर्थः ॥

(उद्द्योतः) आमन्त्रितस्येति षष्ठ्यनुपपत्तेराह—**आमन्त्रिते इति** ॥

(आमन्त्रितकारकोदाहरणबाधकभाष्यम्)

नास्त्यत्र विशेषः सति च पराङ्गवद्भावेऽसति वा ॥

(प्रदीपः) **नास्त्यत्रेति** । कुण्डशब्दो **नब्विषयस्यानिसन्तस्ये**त्याद्युदात्तः । आमन्त्रितस्य पदात्परस्य निघातः । सत्यपि पराङ्गवद्भावे सुबन्तसमुदायस्याद्युदात्तत्वं शेषनिघातश्चेति भेदाभावः ॥

(उद्द्योतः) **कुण्डशब्द इति** । न च यदाऽटन्निति पादादौ वर्तते, यदा वा जीवति पत्यौ जारजवाची कुण्डशब्दः पुल्लिङ्गस्तदा स्वरभेदोऽस्त्येवेति वाच्यम् । पादादावेवंविधप्रयोगाभावात् वृषादित्वेन कुण्डशब्दमात्रस्याद्युदात्तत्वाच्चेति भाष्याशयः ॥

(उदाहरणान्तरभाष्यम्)

इदं तर्हि—परशुना वृश्चन् ॥

(प्रदीपः) **परशुनेति** । परशुशब्द आङ्परयोः खनिशॄभ्यां डिच्चेति कुप्रत्ययान्तोऽन्तोदात्तः ॥

(१२२४ आक्षेपस्य प्रकारान्तरवार्तिकम् ॥ २ ॥)

॥ * ॥ तन्निमित्तग्रहणं वा ॥ * ॥

(व्याख्याभाष्यम्)

अथ वा तन्निमित्तग्रहणं कर्तव्यम् । आमन्त्रितनिमित्तं परस्याङ्गवद्भवतीति वक्तव्यम् । मद्राणां राजन् ॥

(प्रदीपः) **तन्निमित्तग्रहणं वेति** । वाशब्दो विकल्पे । तस्यामन्त्रितस्य यन्निमित्तं तद्वाचि पराङ्गवद्भवतीत्यर्थः ॥ **मद्राणां राजन्निति** । मद्रनिमित्तं हि राजत्वमित्यस्ति तन्निमित्तत्वम् । भृत्यदेशनिमित्ता हि राजता ॥

(उद्योतः) तस्यामन्त्रितस्येति । आमन्त्रितार्थस्येत्यर्थः । तत्प्रवृत्तिनिमित्तस्येति यावत् ॥

(अनन्यथासाधकत्वभाष्यम्)

तच्चावश्यमन्यतरद्वक्तव्यम् ॥

(१२२५ अन्यथासिद्धिवारकवार्तिकम् ॥ ३ ॥)

॥*॥ अवचने हि सुबन्तमात्रप्रसङ्गः ॥*॥

(व्याख्याभाष्यम्)

अनुच्यमाने ह्येतस्मिन्सुबन्तमात्रस्य पराङ्गवद्भावः प्रसज्येत । अस्यापि प्रसज्येत । "क्षत्रेणाग्ने स्वायुः संरभस्व" मित्रेणाग्ने मित्रधेये यतस्व" ॥

(प्रदीपः) **क्षत्रेणाग्न इति** । क्षत्रमित्रयोराख्यातवाच्यक्रियापेक्षया करणत्वादामन्त्रितं प्रति निमित्तत्वाभावः । क्रियाद्वारकं तु व्यपेक्षालक्षणं सामर्थ्यमस्तीति स्यात्पराङ्गवद्भावः । इह वचनेनातिप्रसङ्गे निरस्ते पूर्वसूत्र एकार्थीभाव एव सामर्थ्यमाश्रितम् । अन्यथा तु द्विविधमपि सामर्थ्यमाश्रीयेत ॥

(उद्योतः) **क्रियाद्वारकं त्विति** । व्यपेक्षावादे कृतः सर्वो मृत्तिकयेत्यादौ समासापत्तेरिदं चिन्त्यम् ॥ भाष्यस्य तु समर्थपरिभाषानुपस्थितौ तदननुवृत्तौ च तात्पर्यम् ॥ **समर्थसूत्रे** एकार्थीभावस्यैव सिद्धान्तितत्वेन तस्या अत्रायोगात् । अत एव भो देवदत्त भगो देवदत्तेत्यादौ पराङ्गवत्त्वं नेति बोध्यम् ॥ षष्ठ्यामन्त्रितकारकत्वस्य तन्निमित्तस्य चाभावात् 'ऋतेन मित्रावरुणावृतावृधावित्यत्र ऋतेनेत्यस्यानशाथे इति क्रियान्वयेनामन्त्रितऋतावृधावित्यर्थनिमित्तत्वाभावान्न पराङ्गवत्त्वम् । मित्रावरुणावित्यस्य तु ऋतस्य वर्द्धयिताराविर्त्यर्थकऋतावृधावित्येतत्प्रवृत्तिनिमित्तभूतवर्धनं प्रति कर्तृतया मित्रावरुणयोर्निमित्तत्वात् सिद्ध इष्टः पराङ्गवद्भावः छान्दसत्वादेति बोध्यम् । उपक्रमस्थभाष्यं तु पूर्वपक्षत्वाच्चार्थसाधकम् ॥ नन्वेकार्थीभावसामर्थ्यस्यैव समर्थसूत्रे सिद्धान्तितया कथमत्र पराङ्गवद्भावे तदुपस्थितिरित्यत आह—**इहेति** । एवं च सवग्रहणं व्यर्थमिति तत्त्वम् ॥

(आक्षेपभाष्यम्)

किं पुनरत्र ज्यायः ? ॥

(प्रदीपः) **किं पुनरत्रेति** । गुरुलाघवमनादृत्य प्रयोजनापेक्षः प्रश्नः ॥

(उद्योतः) गुरुलाघवेति । गुरुपदेन गुरुत्वपरेण लाघवपदस्य द्वन्द्वः ॥

(समाधानभाष्यम्)

तन्निमित्तग्रहणमेव ज्यायः । इदमपि सिद्धं भवति—गोषु स्वामिन् पशुषु स्वामिन् । एतद्धि नैव षष्ठ्यन्तम्, नाप्यामन्त्रितकारकम् ॥

(प्रदीपः) **गोषु स्वामिन्निति** । स्वामीश्वरेति शेषषष्ठीविषये सप्तमीविधानान्नास्ति कारकत्वम् । निमित्तत्वं तु पूर्वोक्तन्यायेनास्ति ॥

(१२२६ आक्षेपवार्तिकम् ॥ ४ ॥)

॥ * ॥ सुबन्तस्य पराङ्गवद्भावे समानाधिकरणस्योपसंख्यानमनन्तरत्वात्स्वरेऽवधारणाच्च ॥ * ॥

(व्याख्याभाष्यम्)

सुबन्तस्य पराङ्गवद्भावे समानाधिकरणस्योपसंख्यानं कर्तव्यम् । तीक्ष्णया सूच्या सीव्यन् तीक्ष्णेन परशुना वृश्चन् ॥ किं पुनः कारणं न सिध्यति ? । अनन्तरत्वात् ॥

ननु च परस्य पराङ्गवद्भावे कृते पूर्वस्यापि भविष्यति ॥

स्वरेऽवधारणाच्च * । स्वरेऽवधारणाच्च न सिध्यति । स्वरेऽवधारणं क्रियते, नानन्तर्ये ॥

(प्रदीपः) **सुबन्तस्येति** । क्रियमाणेऽपि सुब्ग्रहणे सुबन्तसमुदायस्यासुबन्तत्वात्पूर्वस्य च परेण व्यवधानान्न प्राप्नोति ॥ **किं पुनरिति** । व्यवहितस्यापि परत्वसंभवात् परस्य वा पराङ्गवद्भावादामन्त्रितानुप्रवेशादव्यवधानाद्भविष्यतीति प्रश्नः ॥ **अनन्तरत्वादिति** । **तस्मिन्निति निर्दिष्टे पूर्वस्येति** परिभाषोपस्थानान्निर्दिष्टग्रहणस्यानन्तर्यार्थत्वादप्राप्तिरित्यर्थः ॥ **स्वरेऽवधारणाच्चेति** । प्रसिद्धे हि लौकिक आनन्तर्ये स्वरे विधीयमाने पराङ्गवद्भावो विधीयते, न तु पराङ्गवद्भाव एव कर्तव्ये पराङ्गवद्भावेनैवानन्तर्यं संपाद्यते । स्वात्मनि क्रियाविरोधादतिदेशान्तराभावाच्च । यथोक्तं हरिणा **ग्रहणाणूग्रहणे ग्रहणाभाव** इत्यादि । असति तु स्वरग्रहणे विषयभेदाल्लक्षणं भिद्यत इति परस्य आनन्तर्यव्यपदेशे कर्तव्ये पराङ्गवद्भावे कृते पूर्वस्यापि पराङ्गवद्भावो लभ्यते । न च स्वरार्थमानन्तर्यं स्वरशब्देनेहोच्यते । मुख्यार्थसंभवे गौणार्थग्रहणायोगात् । न च **तस्मिन्निति निर्दिष्टे पूर्वस्य तस्मादित्युत्तरस्येति** परि-

भाषाद्वयमादेशविधावेवोपतिष्ठते । **गोतो णित् रुदादिभ्यः सार्वधातुक** इत्यादावप्युपस्थानदर्शनात् ॥

(उद्द्योतः) सुब्ग्रहणेऽपि कृते दोषवारणाय यत्नः कार्य इति गौरवमित्येतत्परं वार्तिकमित्याह—**क्रियमाण इति॥ सुबन्तसमुदायस्यासुबन्तत्वादिति** । अनेन सुप्सुपेत्यादौ दर्शितैकत्वविवक्षाया अतिस्थूलमतिविषयत्वं दर्शयति ॥ भाष्ये—**स्वरेवधारणाचेति** वार्तिकखण्डमवतारयति—**ननु चेति ॥ प्रसिद्ध इति** । सिद्ध इत्यर्थः॥ **ग्रहणाणिति**। अणुदित्सूत्रे ग्रहणकशास्त्रीयाण्ग्रहणे ग्रहणकशास्त्राभाव इत्यर्थः॥ यथा तत्र वाक्यार्थबोधात् प्राक् तस्य लक्ष्यसंस्कारकताया वक्तुमशक्यत्वेनाप्रवृत्तिस्तथात्र स्वरे ग्रहणात्स्वात्मन्यप्रवृत्तिरिति भावः॥ **विषयभेदादिति** । अत एव त्वप्रत्ययान्तात्त्वप्रत्ययसिद्धिः ॥ **गौणार्थेति** । एतेन परम्परया स्वरस्य कर्तव्यत्वमस्त्येवेत्यपास्तम् । साक्षात्स्वरे कर्तव्ये शास्त्रस्य चरितार्थत्वात् ॥ **आदेशविधावेवेति** । **षष्ठीस्थाने** इत्यस्य प्रवृत्तेरित्यभिमानः ॥ एवं च तन्निमित्तग्रहणेन तिङन्तव्यावृत्तिसिद्धेः सुब्ग्रहणे समानाधिकरणे असिद्ध्या च सुब्ग्रहणं न कार्यमिति भाष्याशयः । उत्तरार्थं तु सुबित्यधिकारसूत्रं कर्तव्यमिति बोध्यम् ॥

(१२२७ आक्षेपवार्तिकम् ॥ ५ ॥)

॥ * ॥ परमपि च्छन्दसि ॥ * ॥

(व्याख्याभाष्यम्)

परमपि च्छन्दसि पूर्वस्याङ्गवद्भवतीति वक्तव्यम्। आ ते पितर्मरुतां सुम्नमेतु । प्रति त्वा दुहितर्दिवः । वृणीष्व दुहितर्दिवः ॥

(प्रदीपः) पितर्मरुतामिति । पितरित्यामन्त्रितनिघातेनानुदात्तम् । तस्मात्परं मरुतामित्येतदप्यनुदात्तमेव भवति ॥

(१२२८ आक्षेपवार्तिकम् ॥ ६ ॥)

॥ * ॥ अव्ययप्रतिषेधश्च ॥ * ॥

(व्याख्याभाष्यम्)

अव्ययानां च प्रतिषेधो वक्तव्यः । उच्चैरधीयान ॥

(प्रदीपः) उच्चैरिति । उच्चैर्नीचैः स्वरादिष्वन्तोदात्तौ पठितौ । अधिकरणशक्तिप्राधान्याच्च तन्निमित्तसद्भावः ॥

(उद्द्योतः) स्वरादिष्विति । एवं चानेनैव स्वरेणानयोरवस्थितेराभ्यां परस्याष्टमिकनिघातश्चेति भावः। फिट्स्वरेण प्रत्ययस्वरेण वान्तोदात्तत्वसिद्धेः स्वरादिष्वन्तोदात्तपाठः किमर्थं इति चिन्त्यम् ॥

(१२२९ पर्युदासवार्तिकम् ॥ ७ ॥)

॥ * ॥ अनव्ययीभावस्य ॥ * ॥

(व्याख्याभाष्यम्)

अव्ययीभावस्य नेति वक्तव्यम् । इह मा भूत्—उपाग्न्यधीयान ॥

(प्रदीपः) अनव्ययीभावस्येति । प्रतिषेधप्रतिषेधाद्विधिर्भवति। एतच्च ***लुङ्मुखस्वरोपचाराः प्रयोजनम्*** इत्येतदनपेक्ष्योक्तं भाष्यकारेण । अन्यथा कार्यान्तरेऽव्ययत्वाभावादवक्तव्यमेतत्स्यात् ॥

(स्वरेऽवधारणप्रयोजनाधिकरणम्)

(आक्षेपभाष्यम्)

अथ किमर्थं स्वरेवधारणं क्रियते? ॥

(१२३० समाधानवार्तिकम् ॥ ८ ॥)

॥ * ॥ स्वरेवधारणं सुब्लोपार्थम् ॥ * ॥

(व्याख्याभाष्यम्)

स्वरेवधारणं क्रियते सुपो लोपो मा भूदिति । परशुना वृश्चन् ॥

(प्रदीपः) परशुना वृश्चन्निति । वृश्चन्निति प्रातिपदिकम् । न **चाप्रत्यय** इति प्रत्ययलक्षणेन प्रातिपदिकसंज्ञानिषेधो, **न ङिसंबुद्ध्योरिति** नलोपप्रतिषेधाज्ज्ञापकात् । तत्रासति स्वरग्रहणे पराङ्गवद्भावेन प्रातिपदिकानुप्रवेशात् **सुपो धातुप्रातिपदिकयोरिति** सुपो लुक् प्रसज्येत । स्वरग्रहणे तु सति सुब्लुकि कर्तव्ये पराङ्गवद्भावाभावः ॥

(१२३१ समाधानानर्थक्यवार्तिकम् ॥ ९ ॥)

॥ * ॥ न वा सुबन्तैकान्तत्वात् ॥ * ॥

(व्याख्याभाष्यम्)

न वा कर्तव्यम् । किं कारणम् ? । सुबन्तैकान्तत्वात् । सुबन्तैकान्तः पराङ्गवद्भावो भवति ॥

(प्रदीपः) सुबन्तैकान्त इति । पराङ्गवद्भावविषयत्वात्पराङ्गवद्भाव उच्यते । पराङ्गवदित्यत्र आमन्त्रितं संनिधानात्परशब्देन गृह्यते । तच्च सुबन्तमेवेति सुबन्तकार्य एव पराङ्गवद्भावोन्तरङ्गत्वान्न तु प्रातिपदिककार्य इत्यर्थः ॥

(उद्द्योतः) पराङ्गवद्भावविषयत्वादिति । अन्यथा सुबन्तैकान्त इत्यनेनानन्वयापत्तिरिति भावः । पराङ्गवत् भावो यस्य स पूर्वशब्दस्तेनोच्यत इति कश्चित् ॥ **अन्तरङ्गत्वादिति** । सन्निपरशब्देन वाच्यवृत्त्योपस्थानादित्यर्थः ॥

(१२३२आनर्थक्यबाधकवार्तिकम् ॥ १० ॥)

॥ * ॥ प्रातिपदिकैकान्तस्तु सुब्लोपे ॥*॥

(व्याख्याभाष्यम्)

प्रातिपदिकैकान्तस्तु भवति सुब्लोपे कृते ॥

(प्रदीपः) प्रातिपदिकैकान्त इति । अस्याभिप्रायः—आमन्त्रिते परतो यत्सुबन्तं तत्पराङ्गवद्भवति । परं चात्र सुब्लोपे कृते प्रातिपदिकमेवेति तदङ्गत्वात्सुब्लोपः प्राप्नोत्येव ॥

(उद्योतः) **प्रातिपदिकमेवेति** । एवोऽप्यर्थे । परस्मिन्प्रातिपदिकत्वस्यापि सत्त्वेन तदवयवत्वस्याप्यापत्तिरिति भावः ॥

(आनर्थक्यसाधकभाष्यम्)

प्रत्ययलक्षणेन सुबन्तैकान्तता स्यात् । तस्मात्स्वरेवधारणं न कर्तव्यं सुबलोपार्थं प्रातिपदिकस्थायाः सुपो लुगुच्यते । तस्मात्स्वरग्रहणेन नार्थः ॥

(प्रदीपः) **प्रत्ययलक्षणेनेति** । प्रत्ययो निमित्तं लक्षणं यस्यामन्त्रितव्यपदेशस्य तेन सुबन्तैकान्तत्वमित्यर्थः । विशेषणत्वेनाप्युपात्तमामन्त्रितं प्रत्यासत्त्या परशब्देन संबध्यत इति सुबन्ताङ्गवद्भावो विधीयते न तु प्रातिपदिकाङ्गवद्भाव इत्यर्थः ॥ **प्रातिपदिकस्थाया इति** । भाष्यकारवचनप्रामाण्यात् सुप्शब्दस्य स्त्रीलिङ्गत्वम् ॥

(उद्योतः) प्रत्ययलक्षणेन सुबन्तत्वे स्वतः प्रातिपदिकत्वेन तदवयवत्वमपि स्यादत आह—**प्रत्ययो निमित्तमिति** ॥ **तेन सुबन्तैकान्तत्वमिति** । अत्र प्रातिपदिकत्वस्य वस्तुगत्या सत्त्वेपि रूपेणानुद्देश्यत्वान्न तदतिदेशेन तदवयवत्वव्यवहार इति भावः ॥ **विशेषणत्वेनापीति** । पराङ्गवद्भावस्येत्यर्थः ॥ **संबध्यते इति** । बाध्यतया गृह्यत इत्यर्थः । न च **सुद्दतिथोरि**त्यादौ तथयोर्विहितस्य सुटः प्रत्ययावयवत्ववत्प्रकृतेपि प्रातिपदिकावयवत्वमिति वाच्यम् । अवयवावयवाङ्गुल्यादौ शरीरावयवत्वस्य लोकसिद्धत्वादुपपत्तेः । प्रकृते तु प्रातिपदिकावयवकसुबन्तावयवो न तदवयवो भवति । नहि हस्तावयवकशरीरावयवोऽङ्घ्रिर्हस्तावयव इति भावः ॥ **भाष्यकारेति** । सुप इत्यस्य विभक्तिर्यदा विशेष्यं तदा न्यायत एव स्त्रीत्वमिति कश्चित् । **औङः श्या**मित्यादौ नित्यस्त्रीत्वेन नदीत्वाय स्वतः स्त्रीलिङ्गत्वस्यैव न्याय्यत्वात् ॥

(प्रयोजनान्तरभाष्यम्)

इदं तर्हि प्रयोजनम्—षत्वणत्वे मा भूतामिति । कूपे सिञ्चन् । चर्म नमन्निति ॥

(प्रदीपः) **कूपे सिञ्चन्निति** । पराङ्गवद्भावे सत्यैकपद्यात्सकारस्य पदादित्वाभावात् षत्वप्रसङ्गः ॥ **चर्म नमन्निति** । सति पराङ्गवद्भावे समानपदस्थत्वाण्णत्वं स्यात् ॥

(उद्योतः) **समानपदस्थत्वादिति** । अतिदेशेन परावयवतया विशिष्टस्याखण्डत्वे बोधिते स्वाश्रयस्य सखण्डत्वस्यातिदिश्यमानधर्मविरुद्धतया तत्प्रयुक्तणत्वप्रतिबन्धाभाव इति भावः ॥

(प्रयोजननिरासभाष्यम्)

एतदपि नास्ति प्रयोजनम् । इह तावत्कूपे सिञ्चन्निति स्वाश्रयं पदादित्वं भविष्यति ॥

(प्रदीपः) **स्वाश्रयमिति** । विरोधाभावादतिदेशेन स्वाश्रयं पदादित्वं न बाध्यते । यथेहामन्त्रितस्य कार्यं शब्देन बोध्यते तत्पूर्वस्य पराङ्गवद्भावात्तत्सहितस्य भवतु, सकारस्य यत् स्वाश्रयं पदादित्वं तत्केन व्याहन्यते । न चात्रातिदेशिकं कार्यमस्तीति स्वाश्रयं भवत्येव । यथा नमते दण्डः स्वयमेवेत्यत्र शप् ॥

(उद्योतः) नन्वस्य उक्तरीत्या विरोधोस्त्येवेत्यत आह—**यथेहेति** । पूर्वस्य पराङ्गवद्भावोक्तेस्तेन पूर्वस्मिन् परप्रयुक्तकार्यप्रवृत्त्या पूर्वनिष्ठस्वाश्रयनिवृत्तावपि परस्मिन् पूर्वनिष्ठकार्यप्रवृत्तौ परनिष्ठस्वाश्रयनिवृत्तौ च मानाभावादिति भावः ॥ किं चामन्त्रिते परे पूर्वं प्रत्यासत्त्या आमन्त्रितरूपपराङ्गवत् कार्यभागिति उक्ते आमन्त्रितत्ववैकल्यप्रयुक्ताप्राप्तकार्यातिदेश एव लभ्यते न षत्वणत्वयोस्तद्ध्वनयन्नाह । **शब्देनेति** । आमन्त्रितशब्देनेत्यर्थः ॥ **यथा नमत इति** । अन्तर्भावितण्यर्थोऽत्र नमिः । नदुहेति कर्मवत्त्वाश्रययकि प्रतिषिद्धे कर्त्राश्रयः शप् तत्र निषेधादतिदेशाश्रया प्रवृत्तिः । इह तु अतिदेशस्याप्रवृत्तिरेवेति यथाकथंचित् दृष्टान्ततेति बोध्यम् ॥

(प्रयोजननिराकरणैकदेशिभाष्यम्)

चर्म नमन्निति "पूर्वपदात्संज्ञायामग" इत्येतस्मान्नियमान्न भविष्यति ॥

(प्रदीपः) **पूर्वपदात्संज्ञायामिति** । पराङ्गवद्भावात् सत्यपि निमित्तनिमित्तिनोः समानपदस्थत्वे **पूर्वपदात्संज्ञाया**मिति नियमादत्रासंज्ञायां णत्वं न भविष्यतीत्यर्थः ॥

(उद्योतः) यद्यप्यनेन णत्वमपि परिहृतं तथापि प्रकारान्तरेणापि समाधातुमेकदेश्याह—भाष्ये—**चर्म नमन्निति** । तद्ध्वनयन्नाह—**सत्यपि निमित्तेत्यादि** ॥ **नियमादत्रेति** । यद्यपि विध्यर्थत्वमेवाष्टमे स्थापयिष्यति तथापि योगविभागेनात्र नियमोपपत्तिरित्यभिमानः ॥

(निराकरणबाधकभाष्यम्)

ननु च समास एवैतद्भवति पूर्वपदमुत्तरपदमिति ॥

(प्रदीपः) **ननु चेति** । पूर्वपदशब्दस्य समासावयव एव रूढत्वादिति भावः ॥

(उद्योतः) **समासावयव एवेति** । एवं च नियमेन वाक्यव्यावृत्तिः कर्तुमशक्येति भावः ॥

(निराकरणसाधकैकदेशिभाष्यम्)

नेत्याह । अविशेषेणैव तद्भवति—पूर्वं पदं पूर्वपदम् । उत्तरं पदमुत्तरपदम् ॥ सुबामन्त्रिते ॥ २ ॥

(प्रदीपः) **अविशेषेणेति** । व्याप्तिन्यायाश्रयादत्र यौगिकः पूर्वपदशब्दो गृह्यत इत्यर्थः ॥ एवं स्वरग्रहणे प्रत्याख्याते समानाधिकरणस्योपसंख्यानं न कर्तव्यम् । परस्य पराङ्गवद्भावे कृतेपि विषयभेदाल्लक्षणस्यावर्तनात् पूर्वस्य पराङ्गवद्भावस्य सिद्धत्वात् ॥ २ ॥

(उद्योतः) भाष्ये—**अविशेषेणेति** एकदेश्युक्तिः अष्टमे रूढयोरेवानयोर्ग्रहणस्य सिद्धान्तयिष्यमाणत्वात् अखण्डपदस्यैव तत्र

समानपदेन ग्रहणाच्च । उक्तयुक्त्यैव तु णत्ववारणं बोध्यम् ॥ एवं च स्वरग्रहणमपि व्यर्थमिति बोध्यम् ॥ २ ॥

(समाससंज्ञाप्रकरणम्)

(२२३ अधिकारसूत्रम् ॥ २।१।२ आ. २ सू.)

३५२ प्राक्कडारात्समासः ॥ २।१।३ ॥

(प्राग्ग्रहणप्रयोजनाधिकरणम्)

(आक्षेपभाष्यम्)

प्राग्वचनं किमर्थम्? ॥

(प्रदीपः) **प्राक्कडारात्** ॥ ३ ॥ **प्राग्वचनमिति** । अत्रावधित्वद्योतनाक्षेपद्वारेणावधेरप्याक्षेपः । **समास** इत्येव स्वरितत्वादधिकारोऽस्तु यथा **प्रत्यय** इति । अनवकाशत्वाच्च समाससंज्ञायाः संज्ञान्तरैः समावेशो भविष्यतीति प्रश्नः ॥

(उद्द्योतः) **प्राक्क** ॥ ३ ॥ **अवधित्वद्योतनेति** ॥ अत्र करणे ल्युट् कर्तुः करणत्वविवक्षया बोध्यः । द्योतकाक्षेपेत्यर्थः ॥

(१२३३ समाधानवार्तिकम् ॥ १ ॥)

॥ * ॥ प्राग्वचनं समाससंज्ञाऽनिवृत्त्यर्थम् ॥ * ॥

(व्याख्याभाष्यम्)

प्राग्वचनं क्रियते समाससंज्ञाया अनिवृत्तिर्यथा स्यात् । अक्रियमाणे प्राग्वचने अनवकाशा अव्ययीभावादयः संज्ञाः समाससंज्ञां बाधेरन्, ता मा बाधिषतेति प्राग्वचनं क्रियते ॥

(प्रदीपः) **संज्ञानिवृत्त्यर्थमिति** । समाससंज्ञायाः संज्ञान्तरविषये अनिवृत्तिर्यथा स्यादित्यर्थः । अन्यथा एकसंज्ञाधिकारात् पर्यायः स्यात् ॥

(उद्द्योतः) **पर्यायः स्यादिति** । अधिकारलब्धसमाससंज्ञाया अनवकाशत्वादित्याशयः ॥ अनेन अग्रिमग्रन्थ एकदेशिनोक्तिरिति सूचितम् ॥

(एकदेशिनआक्षेपभाष्यम्)

अथ क्रियमाणेऽपि प्राग्वचने यावता अनवकाशा अव्ययीभावादिसंज्ञाः कस्मादेव न बाधन्ते? ॥

(एकदेशिनःसमाधानभाष्यम्)

क्रियमाणे हि प्राग्वचने सत्यां समाससंज्ञायामेता अवयवसंज्ञा आरभ्यन्ते । तत्र वचनात्समावेशो भविष्यति ॥

(प्रदीपः) **सत्यां समाससंज्ञायामिति** । स्वरितत्वादेवाधिकारे लब्धे **प्राक्कडारादि**त्युपादानसामर्थ्यात् प्राग्ग्रहणमावर्तते । तेन प्राक् समाससंज्ञका भवन्ति, समासाः सन्तोऽव्ययीभावादिसंज्ञका इति समावेशः सिध्यति ॥ **अवयवसंज्ञा इति** । समाससमूहापेक्षया कस्यचित् समासस्य काचित् संज्ञेत्येवमुक्तम् ॥

(उद्द्योतः) भाष्ये—**सत्यां समाससंज्ञायामिति** । प्राक्पदोपादानेऽस्याधिकारतया एव तत्सामर्थ्येन वक्तव्यतया तत्साहित्येनासां विधानाद्वचनात्समावेशः ॥ नन्वेवमपि पर्यायः प्राप्नोति कथं समावेश इति चेत्तत्राह—**स्वरितत्वादेवेति** । प्रत्यय इत्यादिवत् । अन्यथा **'समासः सह सुपा'** इत्येकमेव पठेदिति भावः ॥

(समाधानबाधकभाष्यम्)

समाससंज्ञाप्यनवकाशा । सा वचनाद्भविष्यति ॥

(प्रदीपः) **समाससंज्ञापीति** । ततश्चान्तरेणापि यत्नं समावेशः सिद्ध्यति ॥

(उद्द्योतः) अधुनाधिकारत्वाभावेऽपि समावेशं शङ्कते—**समाससंज्ञापीति** । प्राग्ग्रहणाभावे **'समासः सह सुपा'** इत्येव सर्वत्र समाससंज्ञाविधिः सह सुपेत्यंशस्य च स्वरितत्वप्रतिज्ञानादुत्तरत्र संबन्धोऽपि । अव्ययीभावादिसंज्ञाविनिर्मुक्तसमासस्य चाभाव इत्यभिमानः । अत एव **विस्पष्टपट्वादयोऽवकाशा** इत्यग्रिमभाष्यं संगच्छते । स ह्यव्ययीभावादिसंज्ञाविनिर्मुक्तो विषय इति भावः ॥

(समाधानसाधकभाष्यम्)

सावकाशा समाससंज्ञा ॥ कोऽवकाशः? । विस्पष्टादीन्यवकाशः । विस्पष्टं पटुः विस्पष्टपटुः । व्यक्तं पटुः व्यक्तपटुः ॥

(प्रदीपः) **विस्पष्टपटुरिति** । विस्पष्टं पटुरिति विग्रहः । विस्पष्टादयः प्रवृत्तिनिमित्तस्य पाटवादेर्विशेषणानि न तु द्रव्यस्येति विस्पष्टमिति नपुंसकत्वम् । अत एव मुख्यं सामानाधिकरण्यं नास्तीति तत्पुरुषाभावः । यथा **शेष** इत्येतल्लक्षणमधिकारश्च, तथा **सह सुपे**त्यपीति समाससंज्ञा प्रवर्तते ॥

(उद्द्योतः) **मुख्यं सामानाधिकरण्यं नास्तीति** ॥ **विशेषणं विशेष्येणे**त्यत्रोभयोपादानसामर्थ्येन शब्दजन्यबोधविशेष्ययोर्यत्र विशेषणविशेष्यभावस्तत्रैव तत्प्रवृत्तेरिति भावः । क्वचिदेकदेशान्वयोऽपि व्युत्पत्तिवैचित्र्यादिति तात्पर्यम् ॥

(समाधानबाधकभाष्यम्)

नैषोऽवकाशः । एषा ह्याचार्यस्य शैली लक्ष्यते—येनैवावयवकार्यं भवति तेनैव समुदायकार्यमपि भवतीति । येनैव चात्रावयवकार्यं स्वरः क्रियते, तेनैव समुदायकार्यं समासोऽपि भविष्यति—"विस्पष्टादीनि गुणवचनेषु" इति ॥

(प्रदीपः) अवकाशं निराकर्तुमाह—एषा हीति। शीले स्वभावे भवा वृत्तिः शैली। अवयवकार्यमिह पूर्वपदप्रकृतिस्वरः। समुदायकार्यं समाससंज्ञा। वृद्धकुमारीवरन्यायेनान्तरेणापि सहसुपेत्येतस्य लक्षणत्वं सिध्यति॥

(उद्योतः) अवयवकार्यमिति। समासविशेषप्रयुक्तः स्वर इत्यर्थः॥ अन्तरेणापीति। समासाधिकारे स्वरविधानादिति भावः॥

(प्रयोजनसमाधानान्तरभाष्यम्)

इदं तर्हि—काकतालीयमजाकृपाणीयम्॥

(प्रदीपः) काकतालीयमिति। समासाच्च तद्विषयादिति भूतसमासानुवादेन च्छविधानाद् विशेषलक्षणाभावेऽप्यर्थस्यान्यपदार्थत्वेपि मत्वर्थे बहुव्रीहिविधानादुपमानशब्दस्योपमेयवृत्तित्वादन्यपदार्थाभावाद् बहुव्रीहेरभावात् सहसुपेत्यनेनैवात्र समासः कार्यः। तत्र काकतालशब्दौ द्रव्यसहचरितायां क्रियायां वर्तेते। काकस्यागमनमिव चैत्रस्यागमनं तालस्य पतनमिव दस्योरुपनिपात इत्येक इवार्थः। तत्र समासः। ततस्तेन तालेन पतता यथा काकस्य वधस्तथा दस्युना चैत्रस्येति द्वितीय इवार्थः। तत्र च च्छप्रत्ययः॥

(उद्योतः) भूतसमासेति॥ सिद्धसमासेत्यर्थः। इवार्थेनेति। इवद्योत्योपमानत्वनिरूपकोपमेयरूपार्थस्य समासवाच्यस्येत्यर्थः। तदस्यति—उपमानशब्दस्योपमेयवृत्तित्वादिति॥

(प्रयोजननिरासभाष्यम्)

एतदपि नास्ति प्रयोजनम्। अत्रापि येनैवावयवकार्यं प्रत्ययोत्पत्तिः क्रियते, तेनैव समुदायकार्यं समाससंज्ञा भविष्यति "समासाच्च तद्विषयाद्" इति॥

(प्रदीपः) अत्रापीति। पूर्ववज्ज्ञापनेन समाससिद्धिः॥

(उद्योतः) भाष्ये—येनैवावयवकार्यमिति। कर्मधारयः। काकतालीयमित्यत्रावयवरूपच्छप्रत्ययाख्यं कार्यमित्यर्थः। तत्र काकतालेत्यादि पश्चमे व्याख्यास्यते॥

(प्रयोजनान्तरभाष्यम्)

इदं तर्हि—पुनाराजः पुनर्गवः॥

(प्रदीपः) पुनाराज इति। अजिति योगविभागेन तत्पुरुषसंज्ञां विना रूपसिद्धिं मन्यते॥

(प्रयोजननिरासभाष्यम्)

अत्राप्यवश्यं तत्पुरुषसंज्ञा वक्तव्या। तत्पुरुषाश्रयः समासान्तो यथा स्यात्॥

(प्रदीपः) तत्पुरुषाश्रय इति। पुनर्गवीतिङीवर्थष्टजेवैष्टव्यः। तत्राव्ययं प्रवृद्धादिभिरिति वा मयूरव्यंसकादित्वाद्वा तत्पुरुषः॥

(उद्योतः) ङीबर्थ इति। पुनाराज इत्यत्रापि योगविभागस्य भाष्यानुक्तत्वेनाप्रमाणतया टजेष्टव्य इति बोध्यम्। पुनर्गवः पुनाराज इत्युपात्तोदाहरणमादायैव भाष्यप्रवृत्तेरिदं चिन्त्यम्॥

(प्रयोजनभाष्यम्)

इदं तर्हि—पुनराधेयम्॥

(प्रदीपः) पुनराधेयमिति। विशेषकार्यादर्शनात् समाससंज्ञामेव मन्यते॥

(प्रयोजननिराकरणभाष्यम्)

अत्राप्यवश्यं गतिसंज्ञा वक्तव्या "गतिकारकोपपदात्कृद्" इत्येष स्वरो यथा स्यात्॥

(प्रदीपः) अत्रापीति। ततश्च कुगतिप्रादय इति तत्पुरुषः। तत्र यतो नाव इति धेयशब्दस्याद्युदात्तत्वात् पुनराधेयशब्दैकार उदात्तः। गतिसंज्ञायास्त्वभावे समान्तोदात्तत्वं स्यात्॥

(उद्योतः) एकार उदात्त इति। कृदुत्तरपदप्रकृतिस्वरेणेत्यर्थः॥

(प्रयोजनभाष्यम्)

इदं तर्हि—पुनरुत्स्यूतं वासो देयम्॥

(प्रदीपः) पुनरुत्स्यूतमिति। पुनःशब्दस्य गतिसंज्ञायां सत्यां थाथेत्यन्तोदात्तत्वेन भाव्यम्। असत्यां तु समासान्तोदात्तत्वेनेति विशेषाभावाद् गतिसंज्ञाया अभावात् समाससंज्ञाया एव भावं मन्यते॥

(प्रयोजननिरासभाष्यम्)

अत्राप्यवश्यं गतिसंज्ञा वक्तव्या "गतिर्गतौ" इति निघातो यथा स्यात्। यदि तन्नास्ति "*पुनश्चनसौ छन्दसि*" इति॥ सति तस्मिंस्तेनैव सिद्धम्॥

(प्रदीपः) अत्रापीति। असत्यां गतिसंज्ञायां समासान्तोदात्तत्वं स्यात्, सत्यां तु गतिरनन्तर इत्यत्रानन्तरग्रहणसामर्थ्यात् थाथादिस्वरं बाधित्वोच्छब्दस्य प्रकृतिस्वर उदात्तो भवति। पुनःशब्दस्य तु शेषनिघातं परत्वाद् बाधित्वा गतिर्गताविति निघातो भवति॥ यदि तन्नास्तीति। छन्दसि स्वरव्यत्ययविधानान्नावश्यं कर्तव्यमिति भावः॥ भाषायां तु पुनराधेयादौ स्वरसिद्धये पुनःशब्दस्य गतिसंज्ञा वक्तव्या। काठके तु पुनरुत्स्यूतशब्दोन्तोदात्तः पठ्यते। तत्र स्वरव्यत्ययो बोद्धव्यः प्रवृद्धादेराकृतिगणत्वाद्वा॥

(उद्योतः) निघातं परत्वाद्बाधित्वेति। एवं च भाष्यस्य निष्फलतापत्तिः शेषनिघातेनैव तत्फलसिद्धेरिति चिन्त्यम्। गतिर्गताविति निघातो यथा स्यादिति भाष्ये। यद्यप्युच्छब्दस्य प्रकृतिस्वरे प्रवृद्धादित्वादन्तोदात्तत्वे वा शेषनिघातेनापि गतिश्चेति सूत्रस्थकैयटोक्तरीत्या अत्रत्यकैयटरीत्या च पुनःशब्देऽनुदात्तत्वं सिद्धमिति तत्फलसिद्धयेवश्यं गतिसंज्ञा वक्तव्येति वक्तुमनुचितम्। गतिश्चेति—सूत्रे 'पुनरुत्स्यूतशब्दः प्रवृद्धादित्वादन्तोदात्तः' इत्युक्तम्, इह 'उच्छ-

न्दस्य प्रकृतिस्वर' इत्युक्तम् । तथापि पुनरुत्स्यूतमित्यादौ असमासे पुनःशब्दस्य निघातरूपफलाय सावश्यं वाच्या, समस्तपुनरुत्स्यूतशब्दस्तु सुपेतिसूत्रेण समासादन्तोदात्त एवेति भाष्याभिप्रायः ॥ नच नित्यसमासत्वात्कथं वाक्यसंभव इति वाच्यम् । एतद्भाष्यप्रामाण्येन छान्दसत्वादेव समासे गतित्वाभावेन गतिसमासस्याप्रवृत्तेः । अत एवोत्तरसूत्रे सुपेत्यस्य लक्षणमेदमुदाहरणं वक्ष्यति भगवान् । अत एव समासार्था गतीतिस्वरार्था वा गतिसंज्ञेति भाष्ये नोक्तम् ॥ छन्दसि पुनःशब्दस्य गतित्वेनैव सिद्धत्वेपि लोके पुनराधेयादौ समाससंज्ञा सावकाशा तत्र गतिसंज्ञाभावेन गतिसमासाप्राप्तेरत आह—भाषायां त्विति । निन्त्यमेतत् । पुनश्चनसौ छन्दसीति गतिसंज्ञाविधायकवार्तिकविरोधात् लोके समस्तपुनराधेयशब्दानभिधानेन समासान्तोदात्तस्यैव तत्र स्वीकारेण वा भाष्योपपत्तेश्च । सति हि तस्मिंस्तेनैव सिद्धमित्यत्रत्यभाष्यस्वरसोप्येवमेवेति दिक् ॥

(प्रयोजनभाष्यम्)

एवमप्येका संज्ञेति वचनान्नास्ति यौगपद्येन संभवः । पर्यायः प्रसज्येत । तस्मात्प्राग्वचनं कर्तव्यम् ॥ प्राक्कडारात् ॥ ३ ॥

(प्रदीपः) ननु सहसुपेत्यत्र भाष्यकारो वक्ष्यति—**यस्य समासस्यान्यल्लक्षणं नास्ति इदं तस्य लक्षणं भविष्यतीति** । अत्र किमिति समाससंज्ञाया अवकाशो निराक्रियते ॥ एवं मन्यते । असंयुक्तविधानात् सर्वार्थत्वं समाससंज्ञाया न तु कतिपयविषयत्वम् । न्यायव्युत्पादनाय त्ववकाशनिराक्रिया ॥ ३ ॥

(उद्योतः) एवं सहसुपेत्यस्य निरवकाशत्वे पूर्वपक्षिणा प्रतिपादिते तावतापि पर्याय एव प्राप्नोतीति न समावेश इत्याह—भाष्ये—**एवमप्येकासंज्ञेतीति** । **तस्मात्प्राग्वचनं कर्तव्यमिति** सिद्धान्ताशयस्तु उक्त एव । एवं च किमित्यवकाशनिराक्रियेति शङ्का तत्समाधानं च कैयटोक्तमसंगतमेव । पूर्वपक्षिणोऽज्ञानस्यावश्यकत्वात् । तेनावकाशनिराकरणेपि सिद्धान्तिनोक्षतेः । अवकाशप्रदर्शनेन तदखण्डनं तु समाधानान्तरसंभवादनादरेण । किंच ज्ञापकेन विस्पष्टपटुः काकतालीयमित्यादौ समासे परेणोक्ते तस्मादेव ज्ञापकादेतस्य सामान्येन विधायकतायामवकाश उक्तप्राय इति सुधियो विभावयन्तु ॥ **एवं मन्यतेऽसंयुक्तविधानादिति** । विपूर्वकधाञः करणे ल्युटः सहसुपेत्यनेन **समास** इत्यस्यासंयुक्तकरणात्तत्संज्ञायाः सर्वार्थत्वं न तु सहसुपेत्येतन्मात्रोदाहरणविषयत्वमित्यर्थः । एवं च तत्तद्विषयसमाससंज्ञाया अनवकाशत्वात्ताभिः समावेश इत्यभिमानः ॥ नन्वेवंविधनिर्दलविचारकरणं भाष्ये अनुचितमत आह—**न्यायव्युत्पादनायेति** ॥ ३ ॥

(२२४ केवलसमाससंज्ञासूत्रम् ॥ २ । १ । २ आ. ३ सू.)

३५३ सह सुपा ॥ २।१।४ ॥

(सहवचनप्रयोजनाधिकरणम्)

(आक्षेपभाष्यम्)

सहवचनं किमर्थम्? ॥

(प्रदीपः) सह ॥ ४ ॥ **वचनमिति** । सुपेति तृतीया सहार्थमाक्षिपति **वृद्धो यूनेति** यथेति प्रश्नः ॥

(१२३४*समाधानवार्तिकम् ॥ १ ॥)

॥ * ॥ सहवचनं पृथगसमासार्थम् ॥ * ॥

(व्याख्याभाष्यम्)

सहग्रहणं क्रियते सहभूतयोरेव समाससंज्ञा यथा स्याद् एकैकस्य समाससंज्ञा मा भूदिति ॥

(प्रदीपः) **एकैकस्येति** । यथा पुत्रेण सहागत इति द्वयोरपि पितापुत्रयोरागमनेन संबन्धः । एवं समाससंज्ञापि प्रत्येकं स्यात् । सहग्रहणे त्वेका समाससंज्ञा सहभूतयोर्भवति ॥

(उद्योतः) सहसुपा ॥ ४ ॥ **सहग्रहणेत्विति** । तत्सामर्थ्यात्समास इत्येकत्वस्य विवक्षणाच्च सहभूतस्यैका संज्ञेति भावः ॥

(आक्षेपभाष्यम्)

किं च स्यात्, यद्येकैकस्य समाससंज्ञा स्यात्? ॥

(प्रदीपः) **किञ्च स्यादिति** । भवतु प्रत्येकं समाससंज्ञा कार्ये दोषाभावात् । **कृत्तद्धितसमासाश्चे**त्यत्र सूत्रे समासश्च समासश्चेत्येकशेष आश्रयिष्यते वाक्यस्य प्रातिपदिकसंज्ञानिवृत्त्यर्थम् । अन्यथा प्रत्ययान्तत्वादेकैकस्य समासस्य विध्यर्थं समासग्रहणं स्यात् । एकशेषे तु समाससमूहस्य संज्ञाविधिर्नियमार्थो भविष्यतीति न कश्चिद्दोषो भवति । **समासाच्च तद्विषयादि**त्यत्र प्रातिपदिकाधिकारात् **समाससमूहस्य** च प्रातिपदिकत्वात् **समासादि**त्येकवचनं न विवक्ष्यते अनभिधानाद्वा एकैकस्माच्छप्रत्ययो न भविष्यतीति भावः ॥

(उद्योतः) ननु यद्यपि प्रत्येकं समासत्वे प्रत्ययान्तत्वात्प्रत्येकं न प्रातिपदिकत्वं तथापि समासस्य समुदायात्मकतया समासग्रहणस्य वाक्यनिवर्तकनियमार्थत्वं नोपपद्यते किंतु विध्यर्थत्वमेव स्यादत आह—**कृत्तद्धितेति** । **एकशेषेत्विति** । समुदायस्यैकार्थीभावेनार्थवत्त्वात्प्राप्तौ नियमार्थं तदिति भावः ॥ काकतालीयमित्यादौ प्रत्येकं छप्रत्ययोत्पत्तिरपि दोषो नेत्याह—**समासाच्चेति** ॥ ननु समुदाये समासत्वाभावोत आह—**प्रातिपदिकत्वादिति** । तत्सामर्थ्यात्समासपदं तत्समूहपरमिति भावः ॥ **एकत्वं च विवक्ष्यत इति** । प्रातिपदिकादित्यनेनान्वयादिति भावः ॥ ननु तद्विरोधात् प्रातिपदिकादित्यस्यासंबन्ध एव स्यादत आह—**अन**-

भिधानाद्वेति। एवं च लक्ष्यानुरोधादेव समासपदं तत्समूहपरमिति भावः॥

(समाधानभाष्यम्)

इह ऋक्पाद इति समासान्तः प्रसज्येत। इह राजाश्व इति द्वौ स्वरौ स्याताम्।

(प्रदीपः) **ऋक्पाद इति।** ऋचपाद इति स्यात्॥ **राजाश्व इति।** यद्यप्यत्र समासान्तः प्राप्नोति, तथापि रूपभेदाभावात् स्वरद्वयप्रसङ्गो दोष उक्तः। ऋक्पादेपि स्वरद्वयप्रसङ्गो बोद्धव्यः॥

(आक्षेपभाष्यम्)

कथं च कृत्वैकैकस्य समाससंज्ञा प्राप्नोति?॥

(प्रदीपः) **कथं च कृत्वेति।** एकार्थीभावे समासविधानात् समुदायस्य च विशिष्टार्थाभिधायित्वात्तस्यैव संस्कार्यत्वात् प्राधान्यात्परतन्त्रत्वादवयवानामप्राधान्यात्समुदायस्यैव हि द्विर्वचनवत् समाससंज्ञा भविष्यति अन्वर्थसंज्ञाविज्ञानाद्वेति भावः॥

(उद्द्योतः) **समुदायस्यैवेति।** अवयवेभ्यः समुदायोतिरिक्तोपीति भावः॥ इदं चिन्त्यम्, सुबन्तं समर्थं समर्थेन सुबन्तेन सह समस्यत इत्यर्थेन प्रत्येकं तस्यतस्य च संज्ञालाभात्समुदाये संस्कार्यत्वस्य दुर्लभत्वात्। किं च समुदायद्विर्वचनदृष्टान्तोऽयुक्तः वैषम्यात् समुदायसंज्ञयावयवानामननुग्रहणात्॥ **अन्वर्थसंज्ञाविज्ञानाद्वेतीति।** वस्तुतः समसनं संक्षेप इत्यन्वर्थः। नचासावनेकस्यैव, एकस्यापि विस्तृतस्य संक्षेपदर्शनाद्। अतोन्वर्थत्वेन कथमेतदर्थलाभ इति चिन्त्यम्॥ तस्माद् गर्गदण्डनन्यायसत्त्वात्कथमेकैकस्य प्राप्तिः। लक्ष्यानुसाराच्च तस्यैव न्यायस्याश्रयणमिति सिद्धान्तिन एव प्रश्नः॥

(आक्षेपबाधकभाष्यम्)

'प्रत्येकं वाक्यपरिसमाप्तिर्दृष्टा' इति। तद्यथा—वृद्धिगुणसंज्ञे प्रत्येकं भवतः॥

(प्रदीपः) इतरोऽगृहीताभिप्राय आह—**प्रत्येकमिति।** एतच्च वृद्धिवार्तिके व्याख्यातं तत एवानुगन्तव्यम्॥

(उद्द्योतः) इतरो लक्ष्यानुसारमज्ञात्वा न्यायमात्राश्रयणेन सहग्रहणमित्याह—**प्रत्येकमिति**॥

(आक्षेपसाधकभाष्यम्)

ननु चायमप्यस्ति दृष्टान्तः—'समुदाये वाक्यपरिसमाप्तिः' इति। तद्यथा—'गर्गाः शतं दण्ड्यन्ताम्' इति अर्थिनश्च राजानो हिरण्येन भवन्ति, न च प्रत्येकं दण्डयन्ति। सत्येतस्मिन् दृष्टान्ते यदि तत्र प्रत्येकमित्युच्यते, इहापि सहग्रहणं कर्तव्यम्। अथ तत्रान्तरेण प्रत्येकमिति वचनं प्रत्येकं गुणवृद्धिसंज्ञे भवतः, इहापि नार्थः सहग्रहणेन॥

(प्रदीपः) **सत्येतस्मिन्निति।** पक्षद्वये स्थिते सामर्थ्यात्कश्चित् कश्चित्पक्ष आश्रीयते। तत्र संयोगसंज्ञावत् समाससंज्ञा पूर्वोक्तेनैव न्यायेन समुदायस्य संभविष्यति। अथ न्यायद्योतनायेह सहग्रहणं क्रियते, वृद्धिगुणसंज्ञयोरपि प्रत्येकमिति वक्तव्यम्। अथ तत्र लक्ष्यदर्शनादिवशात्प्रत्येकं गुणवृद्धिसंज्ञे भवतः तदेहापि पूर्वोक्तात् सामर्थ्यात्समुदायस्य समाससंज्ञा भविष्यतीति नार्थः सहग्रहणेन॥

(उद्द्योतः) **लक्ष्यदर्शनादीति।** आदिना मालादीनां चेति ज्ञापकसंग्रहः। अत्रापि गर्गदण्डनन्यायाश्रयणेन लक्ष्यदर्शनमेव हेतुरिति तत्त्वम्॥

(समाधानभाष्यम्)

एवं तर्हि सिद्धे सति यत्सहग्रहणं करोति—तस्यैतत्प्रयोजनम्—योगाङ्गं यथा विज्ञायेत सति च योगाङ्गे योगविभागः करिष्यते—"सह"। सुप् समस्यते। केन सह?। समर्थेन। अनुव्यचलत् अनुप्राविशत्॥ ततः "सुपा" सुपा च सह सुप्समस्यते। अधिकारश्च लक्षणं च। यस्य समासस्यान्यल्लक्षणं नास्ति इदं तस्य लक्षणं भविष्यति। 'पुनरुत्स्यूतं वासो देयम्' 'पुनर्निष्कृतो रथः'॥

(प्रदीपः) **योगाङ्गमिति।** योगावयव इत्यर्थः॥ **केनेति।** सुपा चेन्नार्थो योगविभागेनेति प्रश्नः॥ **समर्थेनेति।** योगविभागात्तिङन्तेन सह सुपः समासो भवति। योगविभागश्चेष्टप्रसिद्ध्यर्थ इति सर्वत्र समासो न भवति॥ **अनुव्यचलदिति।** सुबिति संख्याया विवक्षितत्वात् पूर्वं वेः समासः पश्चादनोः। तत्र समाससंज्ञायां सत्यां शाकलप्रतिषेधाद्यणादेशो भवति। समासान्तोदात्तत्वं न भवति **तिङ्ङतिङ** इति निघातेन बाधितत्वादिति केचिदाहुः॥ तत्रानोर्गतिर्गताविति निघातः, विशब्द उदात्तः। **उदात्तस्वरितयोर्यणः स्वरितोनुदात्तस्ये**त्यकारः स्वरितः। एवं त्वनुप्राविशदिति प्रयोजनभावाद् भाष्यकारेण उदाहरणमवक्तव्यं स्यात्। तस्मात्सतिशिष्टत्वात् समासान्तोदात्तत्वेनात्र भाव्यमित्यपरे॥ तिङैकत्वस्योक्तत्वात् प्रातिपदिकत्वेपि सुबनुत्पत्तिः॥ अन्ये त्वाहुः—वचनग्रहणादुक्तेष्वप्येकत्वादिषु प्रथमा स्यात्। केवलायाश्च प्रकृतेः प्रयोगाभावाद्भवितव्यमत्र प्रथमैकवचनेन तस्य तु हल्ङ्यादिलोपः क्रियते। अतएवैकपद्यादामनुप्राविशद्देवदत्तेत्याम **एकान्तरमामन्त्रित**मिति निघातप्रतिषेधः समाससंज्ञायाः प्रयोजनमस्त्येवेति तिङन्तनिघातवादिन आहुः॥ **अधिकारश्चेति।** देवदत्तः पचतीति विशेषणसमासनिवृत्त्यर्थोऽतिङित्यादावुत्तरपदानुपादानादुत्तरपदोपस्थापनार्थश्चेति भावः॥ **लक्षणं चेति।** ननु सहेतियोगविभागेनैव समा-

सस्य सिद्धत्वात्सुपेत्यस्य लक्षणत्वे नास्ति प्रयोजनम् । नैष दोषः । योगविभागः कतिपयतिङन्तविषय एव । एतच्चास्मादेव भाष्याद्विज्ञायते ॥ **पुनरुत्स्यूतमिति** । पुनःशब्दस्यासत्यामपि गतिसंज्ञायां **परादिश्छन्दसि बहुलमिति** उद आद्युदात्तत्वं समासान्तोदात्तत्वापवादो भविष्यतीति मन्यते । अथ वा काठकेन्तोदात्तः पठ्यते तदभिप्रायेण पुनःशब्दस्य गतित्वाभावादिदमुदाहरणम् ॥

(उद्योतः) **योगावयव इति** । योगोत्राष्टाध्यायी ॥ यद्यपि योगविभागाभावेपि अवयवावयवस्य समुदायावयवत्वन्यायेनाष्टाध्याय्यवयवत्वमस्त्येव तथापि साक्षादवयवत्वमेवात्र विवक्षितं तच्च योगविभागमन्तरेण न संभवतीति बोध्यम् ॥ **संख्याया विवक्षितत्वादिति** । सुबन्तत्वादेः प्रत्येकसमाप्तत्वाच्चेत्यपि बोध्यम् ॥ अनुव्यचलदित्यत्र समाससंज्ञायाः फलं दर्शयति—**शाकलेति** । अन्यथा पक्षे यणोश्रवणमपि स्यात् इत्यर्थः ॥ स्वरस्तु न फलमित्याह—**समासान्तोदात्तत्वमिति** । केचिन्मतसिद्धस्वरं दर्शयति—**तत्रानोरिति** ॥ केचिन्मतदूषणमाह—**एवं चेति** ॥ **अवक्तव्यमिति** । समासासमासयोः स्वरे रूपे चाविशेषादित्यर्थः । एकादेशस्य सर्वथोदात्तत्वादिति भावः । अनुव्यचलदित्यत्र नित्ययणश्रवणं विशेषः । अयं च नित्यसमास इति तात्पर्यम् ॥ **सतिशिष्टत्वादिति** । वाक्येपि निघातप्रवृत्तेस्तदुत्तरकालिकतया समासस्वरस्य सतिशिष्टत्वमित्यर्थः ॥ **तिङैकस्वर्यमिति** । सुपां यद्यपि स्वप्रकृत्यर्थविशेष्यगतसंख्याभिधायित्वमुत्सर्गस्तथापि ङ्याप्प्रातिपदिकादितिसूत्रस्थभाष्यप्रामाण्येन तिङापि क्रियागतायाः कर्त्रादिसंपन्धादारोपिततत्संख्याया एव भानमिति सिद्धान्ते इदम् ॥ **वचनग्रहणादिति** । **प्रातिपदिकार्थसूत्रस्थात्संख्यार्थकादित्यर्थः** ॥ **केवलायाश्चेति** । प्रातिपदिकसंज्ञासत्त्वेनास्यापि प्रकृतित्वमिति भावः ॥ **हलङ्यादिलोप इति** । योगविभागस्येष्टसिद्ध्यर्थतया छन्दसि तद्विषये एवैतत्समासप्रवृत्तिरिति भावः ॥ एतेन प्रकुर्वीरन्नित्यादौ समासे नलोपः स्यादित्यपास्तम् ॥ सुबुत्पत्तिस्वीकारे संमतिमाह—**अत एवेति** । **अन्येस्त्वित्यरुचिबीजं** तु पचतिकल्पमित्यादावेवं सति बहुवचनादेरापत्तिः । तस्माद्वचनग्रहणेन संख्याप्रवृत्तिनिमित्तकानामेव ग्रहणं नत्वेषांवधानाम् । किंचैषामेकपद्ये प्रागुक्ते निघातप्रतिषेधे च न मानमिति ॥ **अतिङिस्त्यादाविति** । तत्रातिङित्यस्यानवक्लृप्त्यमर्षयोरितिसूत्रस्थभाष्यप्रामाण्येन समासविशेषणतया **समर्थेनेत्यनेनैवोत्तरपदोपस्थित्या** तत्र **सुपेत्यस्यानन्वयेन** च चिन्त्यमेतत् ॥ ननु पुनःशब्दस्य गतित्वात्कुगतीत्येव सिद्धम् । तदभावे तु अनेन समासेपि तत्पुरुषत्वाभावात् **गतिरनन्तर** इति उच्छब्दस्य स्वरानापत्तिरत आह—**पुनःशब्दस्येति** । छन्दसि सर्वविधीनां वैकल्पिकत्वादिति भावः ॥ **मन्यत** इति सूचितामरुचिमाह—**काठकेन्तोदात्त इति** ॥

(न्यूनतापूर्त्यधिकारणम्)

(१२३५ आक्षेपवार्तिकम् ॥ २ ॥)

॥ * ॥ इवेन विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं च ॥ * ॥

(व्याख्याभाष्यम्)

इवेन सह समासो विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं च वक्तव्यम् । वाससीइव । कन्येइव ॥ सह सुपा ॥ ४ ॥

(प्रदीपः) **इवेनेति** । सुपेत्यस्य लक्षणत्वात् समासे सिद्धे कार्यान्तरविधानार्थं वचनम् ॥ **वाससीइवेति** । वासःशब्दो **वस्तेर्णिद्वि**त्यसुन्प्रत्ययान्तत्वादाद्युदात्तः । समासादुत्पन्नस्य सोरव्ययादिति लुक् ॥ **कन्ये इति** । **कन्यारात्रअन्यमनुष्याणामिति** फिट्सूत्रपाठात्कन्याशब्दोन्तस्वरितः ॥ ४ ॥

(उद्योतः) अव्ययादिति लुगिति । तदन्तस्याप्यव्ययत्वादिति भावः ॥ ४ ॥

(अव्ययीभावसमासप्रकरणम्)

(२२५ अधिकारसूत्रम् ॥ २ । १ । २ आ. ४ सू.)

३५४ अव्ययीभावः ॥ २ । १ । ५ ॥

(महासंज्ञाप्रयोजनाधिकरणम्)

(आक्षेपभाष्यम्)

किमर्थं महती संज्ञा क्रियते ? ॥

(प्रदीपः) **अव्ययी ॥ ५ ॥ किमर्थमिति** । लाघवार्थत्वात् संज्ञाकरणस्याल्पाक्षरा संज्ञा कर्तव्येति प्रश्नः ॥

(समाधानभाष्यम्)

अन्वर्थसंज्ञा यथा विज्ञायेत—अनव्ययमव्ययं भवतीत्यव्ययीभावः । अव्ययीभावोव्ययसंज्ञो भवतीत्येतच्च वक्तव्यं भवति ॥ अव्ययीभावः ॥ ५ ॥

(प्रदीपः) **अन्वर्थसंज्ञेति** । बृहत्संज्ञाकरणेन किंचिद् अव्ययकार्यं प्राप्यते अनव्ययमव्ययमिति अव्ययकार्यलाभादित्यर्थः ॥ **न वक्तव्यमिति** । तदकरणे * लुङ्मुखस्वरोपचाराः **प्रयोजनमिति** कथं परिगणनं क्रियत इति चेत् । इह तु क्रियतामन्वर्थत्वेन वा विशिष्टकार्यविषयमव्ययत्वमनुमास्यत इत्यदोषः । पूर्वपदार्थप्राधान्यं त्वव्ययीभावस्य प्रायिकं न तदन्वर्थसंज्ञया सूच्यते । सूपप्रतीत्यादावुत्तरपदार्थस्य प्राधान्यम् । उन्मत्तगङ्गमित्यादावन्यपदार्थप्रधानता ॥ ५ ॥

(उद्द्योतः) अव्ययीभावः ॥ ५ ॥ क्विप्प्रत्ययेन क्वचिदेव कार्येऽव्ययत्वारोपबोधनात्तत्कार्यलाभः ॥ न तद्वन्वर्थेति । शब्दतोऽलाभादिति भावः ॥ प्रायिकत्वमेव दर्शयति—सूपेत्यादि ॥ ५ ॥

(२२६ अव्ययीभावसमाससंज्ञासूत्रम् ॥ २।१।२ आ. ५ सू.)

३५५ अव्ययं विभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासंप्रतिशब्दप्रादुर्भावपश्चाद्यथानुपूर्व्ययौगपद्यसादृश्यसंपत्तिसाकल्यान्तवचनेषु ॥ २।१।६॥

(अनिष्टवारणाधिकरणम्)

(आक्षेपभाष्यम्)

इह कस्मान्न भवति सुमद्राः सुमगधाः सपुत्रः सच्छात्र इति । समृद्धौ साकल्य इति च प्राप्नोति ?॥

(प्रदीपः) अव्ययम् ॥ ६ ॥ इह कस्मादिति । समुदायस्य संस्कार्यत्वात् प्राधान्यात्तस्यैव विभक्त्यादयो विशेषणानि । अस्ति चात्र समुदायात् समृद्धिसाकल्यप्रतिपत्तिरिति प्रश्नः ॥ सपुत्र इत्यत्र साकल्यं प्रतीयते । सपुत्रो भोक्तुमागत इति प्रयोगे पुत्रा अप्यनेनानीताः न कश्चित् परिशेषित इति संप्रत्ययात् ॥

(उद्द्योतः) अव्ययंवि ॥ ६ ॥ समुदायस्येति । गर्गदण्डनन्यायेन सुपा सहितमव्ययं विभक्त्यर्थादिषु वर्तमानमव्ययीभावसंज्ञकमिति वचनव्यक्त्येत्यर्थः ॥

(आक्षेपबाधकभाष्यम्)

नैष दोषः । इह कश्चित्समासः पूर्वपदार्थप्रधानः । कश्चिदुत्तरपदार्थप्रधानः । कश्चिदन्यपदार्थप्रधानः । कश्चिदुभयपदार्थप्रधानः । पूर्वपदार्थप्रधानोऽव्ययीभावः । उत्तरपदार्थप्रधानस्तत्पुरुषः । अन्यपदार्थप्रधानो बहुव्रीहिः । उभयपदार्थप्रधानो द्वन्द्वः । न चात्र पूर्वपदार्थप्राधान्यं गम्यते ॥

(प्रदीपः) इह कश्चिदिति । बाहुल्याभिप्रायेणैतदुच्यते, क्वचिदन्यथापि दर्शनादर्द्धपिप्पलीत्यादौ ॥ अन्यतमप्राधान्यसंभवे अन्वर्थसंज्ञाविज्ञानात्—पूर्वपदार्थप्राधान्य एवाव्ययीभावसंज्ञा भवति । वचनसामर्थ्यात्तु पूर्वपदार्थप्राधान्यासंभवेपि सूपप्रति उन्मत्तगङ्गमित्यादौ प्रवर्तत एव ॥

(उद्द्योतः) अन्वर्थसंविज्ञानादिति । प्राचीनोक्तमहासंज्ञाकरणेन तत्संमतोर्थोप्यस्य संमत इति भावः ॥

(आक्षेपबाधकयुक्त्यन्तरभाष्यम्)

अथ वा नेमे समासार्था निर्दिश्यन्ते ॥ किं तर्हि ? । अव्ययार्था इमे निर्दिश्यन्ते । एतेष्वर्थेषु यदव्ययं वर्तते तत्सुबन्तेन सह समस्यत इति ॥ अव्ययं विभक्ति० ॥ ६ ॥

(प्रदीपः) अथ वेति । अव्ययस्य श्रुतत्वादन्तरङ्गत्वात्तस्यैव विभक्त्यादयो विशेषणानि । तत्र यदोत्तरपदार्थावच्छिन्नाः समृद्ध्यादयः प्रतिपिपादयिषितास्तदाव्ययं समृद्ध्यादीनां वाचकमिति तेषां तदर्थता भवति ॥ सुमद्रा इत्यत्र तु मद्रशब्द एव समृद्धिविशिष्टमर्थमाह, सुशब्दस्तु समृद्धिद्योतको न तु वाचकः ॥ सपुत्र इत्यत्रापि सहशब्दस्तुल्ययोगस्य वाचकः न तु साकल्यस्य । तत्तु प्रकरणादिसहितात्समुदायात्प्रतीयते ॥ ६ ॥

(उद्द्योतः) अव्ययस्य श्रुतत्वादिति । श्रुतत्वरूपान्तरङ्गत्वादित्यर्थः । सूत्रे श्रुतयोरेव प्रथमं संबन्धः पश्चात्प्रकरणलब्धेनेत्येव युक्तमिति भावः ॥ प्रतिपिपादयिषिता इति । विशेष्यतयेति शेषः । तदुक्तमुत्तरपदार्थावच्छिन्ना इति । द्योतकत्वपक्षे तु द्योत्यार्थस्य समभिव्याहृतार्थविशेषणत्वमेवेति भावः ॥ तदाह—समृद्ध्यादीनां वाचकमिति । निपातानां द्योतकत्वं वाचकत्वं च । लक्ष्यानुरोधाच्च व्यवस्थेति भावः ॥ वाचक इति । पुत्रसहित इति सहार्थविशेष्यकबोधादिति भावः ॥ ननु साकल्यस्येति । सतृणमत्तीत्यादौ तु तुल्ययोगस्य बाधेन झटिति प्रथममेव सकलमत्तीति बोधात् साकल्यबोधकता सहशब्दस्येति भावः ॥ अपदिशमित्यादीन्यखण्डान्येवाव्ययानि दिशोर्मध्यादिवाचकानीत्याशयेन भगवता योगविभागो नाकारि ॥ ६ ॥

(२२७ अव्ययीभावसंज्ञासूत्रम् ॥ २ । १ । २ आ. ६ सू.)

३५६ यथा ऽसादृश्ये ॥२।१।७॥

(सूत्रे यथाशब्दस्याव्युत्पन्नस्यैव ग्रहणाधिकरणम्)

(आक्षेपभाष्यम्)

असादृश्य इति किमर्थम् ? ॥

(प्रदीपः) यथा ॥ ७ ॥ असादृश्य इति किमर्थमिति ।

सापेक्षत्वादसामर्थ्यं वृत्तिः सादृश्य एव च ।
पूर्वप्राप्त्यनिषेधश्च प्रश्नेऽस्मिन् कारणत्रयम् ॥

(उद्द्योतः) यथासा ॥ ७ ॥ 'यथाशब्दः सुबन्तेन समस्यते, सादृश्ये द्योत्ये न' इति सूत्रार्थः। यथाशक्तीत्युदाहरणम्। यथार्थत्वेन तु न सिद्धिः,सूत्रगृहीताव्ययेन तेन समासाभावात्।अतः पृच्छति—असादृश्यइति किमर्थमिति ॥ अत एव सूत्रं किमर्थमिति न

प्रश्नः ॥ पूर्वसूत्रे यथाग्रहणं तदर्थार्थकान्वादिभिः समासार्थम् ॥ सापेक्षत्वादिति । उपमानत्वेन बुद्धस्योपमेये साकाङ्क्षत्वादिति भावः ॥ वृत्तिरिति । शक्तिरित्यर्थः । एवं च उदाहरणाप्रसिद्धिरिति भावः ॥ पूर्वप्राप्तीति । अनन्तरत्वात् । एवं च पूर्वेण तत्र समासो दुर्वार इति व्यावर्त्याप्रसिद्धिरिति भावः ॥

(समाधानभाष्यम्)

यथा देवदत्तस्तथा यज्ञदत्तः ॥

(प्रदीपः) यथा देवदत्त इति । समुदायस्य चात्र सापेक्षत्वात्तस्य च प्राधान्यादुपमानस्य चोपमेयं प्रति नित्यसापेक्षत्वात्समासः प्राप्नोति ॥

(उद्द्योतः) समुदायस्य चेति । यद्धर्मवान्देवदत्त इत्यर्थकस्य यथा देवदत्त इति समुदायस्येत्यर्थः ॥ ये तु देवदत्तसादृश्यवान्यज्ञदत्त इति बोधं वदन्ति, तेषां प्रधानस्य सदृशस्य सापेक्षत्वादित्येवालं समुदायस्येत्युक्तेर्वैयर्थ्यम् । मम तु केवलप्रधानार्थस्यासापेक्षत्वात्तथोक्तिः ॥ नित्यसापेक्षत्वादिति । प्रधानस्योपमानस्य सापेक्षत्वान्नित्यसापेक्षस्याचेत्यर्थः । नित्यसापेक्षं सर्वं समस्यत इति भाष्ये क्वास्तीति चिन्त्यम् । देवदत्तस्य गुरुकुलमित्यादिषु गमकत्वाद्वृत्तिः किमोदनः शालीनामित्यादीनामिवेत्येव समर्थसूत्रे भाष्ये उक्तम् । तत्र यथाशब्द उपमानत्वं द्योतयतीत्यभियुक्तोक्तेस्तस्य विशेषणत्वेन पूर्वपदार्थप्राधान्याभावेपि द्विमुनीत्यादिवत्समासप्राप्तिः तदभावे प्रसिद्धत्वादस्यैव ग्रहणं स्यादिति तात्पर्यम् ॥

(आक्षेपभाष्यम्)

असादृश्य इत्युच्यते, तत्रेदं न सिद्ध्यति—यथाशक्ति यथाबलमिति । किं कारणम्? । यथेत्ययं प्रकारवचने थाल्, स च सादृश्ये वर्तते ॥

(प्रदीपः) स च सादृश्य इति । प्रकारशब्दस्य सादृश्यार्थत्वात् प्रकारे व्युत्पादितस्य यथाशब्दस्य सादृश्ये वृत्तिरित्यर्थः ॥

(उद्द्योतः) सादृश्यार्थकत्वादिति । सादृश्यप्रयोजकभेदकधर्मार्थकत्वादिति भावः ॥ अत एव थाल्विधायके वृत्तावुक्तं सामान्यस्य भेदको विशेषः प्रकार इति ॥ वचनपदस्वारस्यात्तु तद्वाचकता । एवं च यथा देवदत्त इत्यादौ यद्धर्मवान्देवदत्तस्तद्धर्मवान्यज्ञदत्त इति बोधे यत्तद्भ्यां तस्य धर्मस्यैक्येऽवगते उपमानोपमेयत्वस्यावगतिरिति सादृश्ये वर्तत इत्यस्य उपमानोपमेयत्वद्योतक इत्यर्थः । ईदृशसादृश्यद्योतकस्यापि ग्रहणेऽसादृश्ये इति प्रतिषेध एव मानमिति बोध्यम् । सादृश्यस्य थाप्रत्ययवाच्यत्वे तु यत्सदृशो देवदत्तस्तत्सदृशो यज्ञदत्त इत्येव बोधः स्यात् ननु देवदत्तयज्ञदत्तयोः सादृश्यबोध इति दिक् ॥ सादृश्ये वृत्तिरिति । सादृश्ये एव वृत्तिरित्यर्थः । एवं च सूत्रं व्यर्थमिति भावः ॥

(आक्षेपबाधकभाष्यम्)

नैष दोषः । अयं यथाशब्दोस्त्येवाव्युत्पन्नः प्रातिपदिकं वीप्सावाचि । अस्ति प्रकारवचने थाल् । तत्र यदव्युत्पन्नं प्रातिपदिकं वीप्सावाचि तस्येदं ग्रहणम् ॥

(प्रदीपः) अस्त्येवेति । अर्थवत्सूत्रारम्भादव्युत्पन्नानामपि सम्भवोऽवगम्यते ॥ **वीप्सावाचीति ।** वीप्साग्रहणमुपलक्षणं तेन योग्यतापदार्थानतिवृत्ती अपि यथार्थौ ॥ **तस्येदमिति ।** सूत्रेस्मिन्नित्यर्थः ॥

(उद्द्योतः) अर्थवत्सूत्रारम्भादिति । बहुपटव इत्याद्यर्थं बहुच्पूर्वं इत्येव कर्तव्यमिति भावः । कृदंशे गतिकारकपूर्वस्य ग्रहणमिति तु ज्ञापकसिद्धस्यासार्वत्रिकत्वान्नेत्याशयः ॥ भाष्ये इदमित्यस्य एतत्सम्बन्धीयमिति वाच्योर्थः । तद् ध्वनयन् व्याचष्टे—सूत्रेस्मिन्निति । इदमुपलक्षणं यथाशक्तीति प्रयोगे चेत्यप्यर्थः ॥

(आक्षेपभाष्यम्)

अथ यः प्रकारवचने थाल्, तस्य ग्रहणं कस्मान्न भवति । पूर्वेण प्राप्नोति—'सादृश्यसंपत्ति' इति ॥

(उद्द्योतः) तत्र यथाशक्तीति प्रयोगे सादृश्यवाचिन एव ग्रहणं कुतो नेति शङ्कते—**अथ य इति ॥** तस्य तदन्तस्य ॥ सादृश्यं तस्य वाच्यमेवास्तु शक्तिसादृश्यमित्यादिरेवार्थोस्तु एतत्सूत्रं च मास्तु इति भावः ॥ अव्युत्पन्नशब्दसत्त्वे मानमपश्यतोर्थघटितं साधुत्वमित्यजानतश्च शङ्केयम् ॥ प्रकृतसूत्रे प्रकारवचनथालन्तस्य ग्रहणमिति न शङ्कार्थः । असादृश्य इत्यस्य सूत्रे श्रवणात् **पूर्वेण प्राप्नोति'** 'सामर्थ्यान्नेत्यस्यासंगतेश्च ॥ नन्वेवं समासो न स्यादत आह—**पूर्वेणेति ॥ सादृश्यसंपत्तीति ।** यथार्थत्वेन तु न प्राप्तिरुक्ता, सूत्रगृहीताव्ययेन तेन समासाभावात् । अत एव पश्चाच्छब्देन न तेन सूत्रेण समासः ॥

(आक्षेपबाधकभाष्यम्)

प्रतिषेधवचनसामर्थ्यान्न भविष्यति ॥ यथाऽसादृश्ये ॥ ७ ॥

(प्रदीपः) प्रतिषेधवचनसामर्थ्यादिति । यथार्थे यदव्ययमिति पूर्वेणैव सिद्धे समासे सादृश्यप्रतिषेधार्थत्वादस्यारम्भस्य ॥ ७ ॥

(उद्द्योतः) उत्तरमाह—**प्रतिषेधेति ।** प्रतिषेधयुक्तसूत्रारम्भेत्यर्थः । एतदर्थमेव सूत्रमावश्यकम् ॥ **यथार्थे यदव्ययमिति** कैयटस्तु चिन्त्यः तेनात्राप्राप्तेरुक्तत्वात् । उपक्रमभाष्यतस्तथैव लाभात् ॥ ७ ॥

(२२८ अव्ययीभावसंज्ञासूत्रम् ॥ २ । १ । २ आ. ७ सू.)

३५८ सुप् प्रतिना मात्रार्थे ॥ ९ ॥

(सुब्ग्रहणप्रयोजनाधिकरणम्)

(आक्षेपभाष्यम्)

सुबिति वर्तमाने पुनः सुब्ग्रहणं किमर्थम्? ॥

(प्रदीपः) सुप्प्रतिना ॥ ९ ॥ सबिति वर्तमान इति । सुबामन्त्रित इत्यतः ॥

(आक्षेपबाधकभाष्यम्)

'अव्ययम्' इत्येवं तद्भूत्। सुब्मात्रे यथा स्यात्—माषप्रति सूपप्रति ओदनप्रति ॥ सुप्प्रतिना ॥ ९ ॥

(प्रदीपः) अव्ययमित्येवमिति । अव्ययग्रहणसंबद्धमभूदित्यर्थः । "यावदवधारणे" इत्यत्र यावच्छब्दोऽव्ययमेव संगृहीतः । तथा च यावन्त्यमत्राणीत्यनव्ययेन वाक्यं प्रदर्श्यते ॥ अन्यथा नित्यसमासत्वाद्वाक्यं न स्यात् । स्वरादीनां च दोषामन्यमहर्दिवामन्या रात्रिरिति शाक्तविषये सत्त्वप्रधानतादर्शनान्मात्रावति वृत्तिरविरुद्धेति अव्ययस्यैवायं समासः स्यात् ॥ ९ ॥

(उद्योतः) सुप्प्रति ॥ ९ ॥ नन्वव्ययग्रहणं यावदवधारणे इत्यत्रैव निवृत्तमयोग्यत्वादिति चेन्नेत्याह—यावदिति । यावदमत्रं ब्राह्मणानामव्ययस्येत्युदाहरणम् ॥ ननु प्रतिना समासयोग्यमात्रावदर्थाव्ययाभावादेव तन्निवृत्तिर्भविष्यतीत्यत आह—स्वरादीनां चेति ॥ मात्रावतीति । तथा च दिवादोषादिभिरव्ययैरेव प्रतिना समासः स्यादित्यर्थः ॥ ९ ॥

(२२९ अव्ययीभावसंज्ञासूत्रम् ॥२।१।२ आ० ८ सू०)

३५९ अक्षशलाकासंख्याः परिणा ॥ २।१।१० ॥

(विभक्तिवचनव्यवहारनियमाधिकरणम्)

(१२३६ विभक्तिनियमवार्तिकम् ॥ १ ॥)

॥ * ॥ अक्षादयस्तृतीयान्ताः परिणा पूर्वोक्तस्य यथा न तद्यथाद्योतने ॥ * ॥

(व्याख्याभाष्यम्)

अक्षादयस्तृतीयान्ताः परिणा सह समस्यन्त इति वक्तव्यम् । पूर्वोक्तस्य यथा न तत् । अयथाजातीयके द्योत्ये । अक्षेणेदं न तथा वृत्तं यथा पूर्वमिति । अक्षपरि शलाकापरि ॥

(प्रदीपः) अक्ष ॥ १० ॥ तृतीयान्ता इति । विभक्त्यन्तरनिरासार्थमेतदुक्तम् । न्यायाच्चैतत् सिध्यति । अक्षादीनां वर्तनक्रियायां कर्तृत्वादित्याहुः ॥ पूर्वोक्तस्येति । पूर्ववृत्तस्येत्यर्थः । अनेकार्थत्वाद्धातूनां नियतविषयत्वाच्च वचिरिह वर्तने वर्तते । तदेव यथा न तदिति तच्छब्देन परामृश्यते । अभिधानार्थे तु वचौ तच्छब्देन परामर्शोसंबद्धः स्यात् ॥

अयथाद्योतन इति । जयकाले अक्षादीनामेकरूपं यद्वर्तनं तद्विपरीतं पराजये यद्वर्तनं तद्यदा परिणा द्योत्यते तदा समासः ॥

(उद्योतः) अक्षशला ॥ १० ॥ विभक्त्यन्तरनिरासार्थमिति । विभक्त्यन्तरभ्रमनिरासार्थमित्यर्थः ॥ कर्तृत्वादिति । वर्तनक्रिया च वृत्तावन्तर्भूता गुडधाना इत्यादौ मिश्रणक्रियावदिति भावः ॥ पूर्ववृत्तस्येत्यर्थ इति । पूर्ववृत्तस्य जयस्य संबन्धि यथा वर्तनमभूत् संप्रति चेत्तद्वर्तनं तथा न भवति तदा समास इत्यर्थः पूर्वोक्तस्य यथेति भाष्यस्येति भावः ॥ वचिरिहेति । एतद्भाष्यप्रयोगे इत्यर्थः । तदेव वर्तनमेव ॥ तस्यैव फलितार्थमाह—भाष्ये—अयथाद्योतन इति । अयथाशब्दो वैपरीत्ये विपरीतत्वद्योतने इत्यर्थः ॥ पराजयद्योतने इति यावत् ॥ पराजय इति । पञ्चानां मध्ये एकेन विपरीतवर्तनेऽयं प्रयोगः । तदा च पराजय एव भवतीत्याशयः । तदेतद् ध्वनयन्वक्ष्यति—पञ्चिकानामद्यूतमिति । तद्विषय एव चायं प्रयोग इष्यते ॥

(१२३७ वचननियमवार्तिकम् ॥ २ ॥)

॥ * ॥ अक्षशलाकयोरेकवचनान्तयोः ॥ * ॥

(व्याख्याभाष्यम्)

अक्षशलाकयोरेकवचनान्तयोरिति वक्तव्यम् । इह मा भूत्—अक्षाभ्यां वृत्तम्, अक्षैर्वृत्तम् ॥

(प्रदीपः) एकवचनान्तयोरिति । समासे द्वित्वाद्यनवगमादेकत्वस्यान्यनिरपेक्षत्वादन्तरङ्गत्वादवगतिसंभवान्न्यायप्राप्तमेतदित्याहुः ॥ यदुक्तम् 'अभेदैकत्वसंख्या वृत्तौ गम्यते' इति तद् बाहुल्याभिप्रायेण ॥

(उद्योतः) यद्यपि द्वयोस्त्रयाणामन्यथापातेपि पराजय एव तथापि तत्र नेष्यतेत आह—भाष्ये—एकवचनान्तयोरिति ॥ न्यायप्राप्तमेतदिति । वस्तुतस्तु—

भवद्भिरामवसरप्रदानाय वचांसि नः,

वध्वोरगारं वध्वगारमित्यादाविव प्रकरणादिनाक्षत्वेनैवानेकार्थावगमे समासवारणाय अक्षत्वेनैकाक्षबोधे एव च साधुत्वाय वचनमावश्यकम् ॥ अभेदैकत्वेति । अस्यार्थः प्रागुक्तः ॥

(१२३८ व्यवहारनियमवार्तिकम् ॥ ३ ॥)

॥ * कितवव्यवहारे च ॥ * ॥

(व्याख्याभाष्यम्)

कितवव्यवहार इति वक्तव्यम् । इह मा भूत्—

अक्षेणेदं न तथा वृत्तं शकटेन यथा पूर्वमिति ॥ अक्षशलाका ॥ १० ॥

(प्रदीपः) कितवव्यवहार इति । पञ्चिका नाम द्यूतं पञ्चभिरक्षैः शलाकाभिर्वा भवति । तत्र यदा सर्वे एकरूपाः पतन्ति तदा पातयिता जयति । अन्यथा तु पाते पराजीयते ॥ १० ॥

——>०<——

(२३० अव्ययीभावसंज्ञासूत्रम् ॥ २।१।२ आ. ९ सू.)

३६० विभाषापपरिबहिरञ्चवः पञ्चम्या ॥ २।१।११ ॥

(योगविभागाधिकरणम्)

(१२३९ वार्तिकम् ॥ १ ॥)

[॥ * ॥ विभाषेति योगविभागः ॥ * ॥]

(भाष्यम्) [विभाषेति] योगविभागः कर्तव्यः । "विभाषा" इत्ययमधिकारः । ततः—"अपपरिबहिरञ्चवः पञ्चम्या" इति ॥

(प्रदीपः) विभा ॥ ११ ॥ योगविभाग इति । अन्यथैतस्योपयोग आशङ्क्येत योगविभागे त्वधिकारो गम्यते ॥

(पञ्चमीग्रहणप्रयोजनाधिकरणम्)

(प्रत्याख्यानभाष्यम्)

अपपरिबहिरञ्चवः पञ्चम्या ॥ पञ्चमीग्रहणं शक्यमकर्तुम् ॥ कथम् ? । सुबन्ते नेति वर्तते । एतैश्च कर्मप्रवचनीयैर्योगे पञ्चमी विधीयते । तत्रान्तरेणापि पञ्चमीग्रहणं पञ्चम्यन्तेन समासो भविष्यति ॥

(प्रदीपः) अपपरिशब्दौ परस्परसाहचर्याद्वर्जनार्थौ गृह्येते । तौ च कर्मप्रवचनीयौ । तद्योगे पञ्चम्येव विहिता । बहिर्योगेपि बहिर्योगे चोपसंख्यानमिति विहिता । अञ्चूत्तरपदलक्षणा च विहिता । प्राग्ग्राम इत्यादौ तु समासो न भविष्यति । पूर्वपदार्थप्राधान्य एव सति संभवे अव्ययीभावस्य विधानादित्यभिप्रायेणाह—पञ्चमीग्रहणमिति ॥ एतैश्चेति । वक्ष्यमाणाङ्पेक्षया बहुवचननिर्देशः ॥

(उद्द्योतः) विभाषाप ॥ ११ ॥ कर्मप्रवचनीययोरपि अपपर्योः संभवाल्लक्षणादौ कर्मप्रवचनीययोरपपञ्चम्यन्तेनापि समासप्रसङ्गाचाह—वर्जनार्थाविति ॥ उपसंख्यानमिति । तच्च बहिर्ग्रामादित्यादिसिद्धये तवाप्यावश्यकमिति भावः ॥ विहितेति । कर्त्तव्येतिशेषः । अन्यथास्योपसंख्यानस्य खपुष्पायमाणत्वादेवं सिद्धवदुक्तिरसंगता स्यात् ॥ अत एव भाष्यकारोपि बहिःशब्देन पञ्चमी न विधीयते इत्याह ॥ नन्वञ्चूत्तरपदाद्यदा प्रथमान्तादस्तातिं विधायाञ्चेर्लुगिति लुक् तदा प्रथमान्तेनापि समानाधिकरणेन तस्य समासः प्राप्नोतीत्यत आह—प्राग्ग्राम इति ॥ अपपर्योरेव कर्मप्रवचनीयत्वाद्बहुवचनानुपपत्तेराह—वक्ष्यमाणेति ॥ भाष्ये—एतैश्च कर्मप्रवचनीयैरित्यत्र छत्रिणो यान्तीतिवल्लक्षणया अञ्चुरपि गृह्यते । अत एव बहुवचनोपपत्तिरित्येके ॥

(प्रत्याख्यानबाधकभाष्यम्)

इदं तर्हि प्रयोजनम् । बहिःशब्देन योगे पञ्चमी न विधीयते तत्रापि यथा स्यात्—बहिर्ग्रामं बहिर्ग्रामात् ॥

(आक्षेपभाष्यम्)

अथ क्रियमाणे पञ्चमीग्रहणे यावता बहिःशब्देन योगे पञ्चमी न विधीयते कथमिवैतत्सिध्यति ॥

(प्रदीपः) अथेति । बहिर्गतो ग्रामादित्यपादाने पञ्चमीसद्भावाद् कथं तद्विधानं ज्ञाप्यत इति प्रश्नः ॥

(उद्द्योतः) बहिर्गतो ग्रामादिति । ग्रामाद्यो गतः स बहिर्वर्त्तत इत्यर्थः ॥

(समाधानभाष्यम्)

पञ्चमीग्रहणसामर्थ्यात् ॥ विभाषापपरि ॥ ११ ॥

(प्रदीपः) पञ्चमीग्रहणसामर्थ्यादिति । बहिर्गतो ग्रामादित्यत्रासामर्थ्यात् समासेन न भवितव्यं तस्मात् षष्ठीविषये पञ्चमी बहिर्योगेनुमीयते ॥ ततस्तदुपसंख्यानं न कर्तव्यम् ॥ ११ ॥

(उद्द्योतः) उपसंख्यानं न कर्त्तव्यमिति । अपूर्वं न कर्त्तव्यमित्यर्थः ॥ ११ ॥

———

(२३१ अव्ययीभावसंज्ञासूत्रम् ॥ २।१।२ आ. १० सू.)

३६१ आङ् मर्यादाभिविध्योः ॥ २।१।१२ ॥

(प्रत्याख्यानभाष्यम्)

मर्यादाभिविधिग्रहणं शक्यमकर्तुम् । कथम् ? ।

पञ्चम्येति वर्तते। आङा च कर्मप्रवचनीयेन युक्ते पञ्चमी विधीयते। तयोश्चैवार्थयोराङ् कर्मप्रवचनीयसंज्ञो भवति नान्यत्र ॥ आङ्मर्यादाभिविध्योः ॥ १२ ॥

(उद्योतः) आङ्म ॥ १२ ॥ एतयोश्चैवार्थयोरिति। अपपरीतिसूत्रे एव चाङ् पठनीय इति भावः ॥ १२ ॥

(२३२ अव्ययीभावसंज्ञासूत्रम् ॥ २। १। २ आ. ११ सू.)

३६४ यस्य चायामः ॥ २।१।१५ ॥

(उदाहरणनिरूपणाधिकरणम्)

(आक्षेपभाष्यम्)

किमुदाहरणम्?॥

(प्रदीपः) यस्य ॥ १५ ॥ किमुदाहरणमिति। लक्ष्यलक्षणयोर्द्वयोरप्यायामवत्त्वात् संदिहानः पृच्छति ॥

(समाधानभाष्यम्)

अनुगङ्गं हास्तिनपुरम्। अनुगङ्गं वाराणसी। अनुशोणं पाटलिपुत्रम् ॥

(आक्षेपभाष्यम्)

"यस्य चायाम" इत्युच्यते। गङ्गा चाप्यायता, वाराणस्यप्यायता, तत्र कुत एतत्—गङ्गया सह समासो भविष्यति, नपुनर्वाराणस्येति?॥

(उद्योतः) यस्यचा ॥१५॥ भाष्ये नपुनर्वाराणस्येति॥ न पुनर्हास्तिनपुरेणेति पाठान्तरम्। यत्संबन्ध्यायामबोधकोऽनुः स तेन सुबन्तेनोपस्थितत्वात्पष्ठ्यन्तेन समस्यत इत्यर्थे गङ्गाया आयाम इत्यर्थेयं समासः स्यात्। वाराणसीशब्देन च तदायामो लक्ष्यः मुख्यार्थेनान्वयबाधात्। एवं च गङ्गायामसदृशो वाराणस्यायाम इति बोध इति वाच्यम्। एवं च वाराणसीशब्देन मुख्यार्थेनानुना समासोऽस्तु, गङ्गाशब्द एव लक्षणयायामे वर्तताम्। एवं च प्रागुक्त एवार्थेऽनुवाराणसि गङ्गेति स्यादिति भावः ॥

(समाधानभाष्यम्)

एवं तर्हि 'लक्षणेन' इति वर्तते। गङ्गा चैव लक्षणम् न वाराणसी॥

(प्रदीपः) गङ्गा चैव लक्षणमिति। अनेकदेशव्याप्त्या गङ्गाया आयामवत्त्वेनानेकजनापेक्षया प्रसिद्धत्वात् तस्या एव लक्षणत्वम्। ततो यद्यपि कस्यचित् पुरुषस्य हास्तिनपुरमायामवत्त्वेन प्रसिद्धं न गङ्गा, तथापि न तदपेक्षया प्रयोगव्यवस्था। किं तर्हि? प्रचुरलोकापेक्षया ॥

(समाधानान्तरभाष्यम्)

अथ वा "यस्य चायामः" इत्युच्यते। गङ्गा चाप्यायता वाराणस्यप्यायता। तत्र प्रकर्षगतिर्विज्ञास्यते—'साधीयो यस्यायामः' इति। साधीयश्च गङ्गायाः, न वाराणस्याः॥ यस्य चायामः॥ १५॥

(प्रदीपः) अथ वेति। लक्षणेनेत्यस्यानुवृत्त्या विनापीष्टसिद्धिं दर्शयति। उपमानोपमेयभावे चायं समास इष्यते। न्यूनगुणं चोपमेयं परिपूर्णगुणमुपमानं तत्र संपूर्णगुणसन्निधौ न्यूनगुणमसद्गुणमिव प्रतिभातीति सामर्थ्यात् प्रकर्षगतिर्विज्ञायते। प्रकृष्टाप्रकृष्टसन्निधौ च प्रकृष्टस्य कार्येण संबन्धो नेतरस्य ॥ १५ ॥

(उद्योतः) भाष्ये—तत्र प्रकर्षगतिरिति। शब्दशक्तिस्वाभाव्यात् उपमानवाचकेनैवायं समास इति भावः ॥ १५ ॥

(२३३ अव्ययीभावसंज्ञासूत्रम् ॥ २। १।२ आ. १२ सू.)

३६५ तिष्ठद्गुप्रभृतीनि च ॥ २।१।१६ ॥

(चकारप्रयोजनाधिकरणम्)

(आक्षेपभाष्यम्)

किमर्थश्चकारः?॥

(प्रदीपः) तिष्ठद्गु ॥ १६ ॥ किमर्थ इति। समुच्चेतव्यस्याभावात् प्रश्नः ॥

(समाधानभाष्यम्)

एवकारार्थः—तिष्ठद्गुप्रभृतीन्येव॥ क मा भूत्? परमं तिष्ठद्गु ॥

(प्रदीपः) एवकारार्थ इति। अनेकार्थत्वान्निपातानामिति भावः। तेन तिष्ठद्गुप्रभृतीन्येवैकार्थीभावविषयाणि भवन्ति। न तु शब्दान्तरेणैकार्थीभावं प्रतिपद्यन्त इत्यर्थः ॥

(उद्योतः) तिष्ठद्गु ॥ १६ ॥ शब्दान्तरेणैकार्थीभावमिति। प्रकरणादेकार्थीभावविषयं समासमित्यर्थः। तन्नयनाह—भाष्ये—परमं तिष्ठद्ग्विति। ध्वनितं चेदं वृत्तौ॥ आ तिष्ठद्गु जपन्संध्यामिति तु भिन्नपदमेव, पञ्चम्याश्चाव्ययादिति लुगिति बोध्यम् ॥

(अर्थविशेषनियमाधिकरणम्)

(१२४० वार्तिकम् ॥ १ ॥)

॥ * ॥ तिष्ठद्गु कालविशेषे ॥ * ॥

(व्याख्याभाष्यम्)

तिष्ठद्गु कालविशेष इति वक्तव्यम्। तिष्ठन्ति गावोऽस्मिन्काले स तिष्ठद्गु। वहद्गु ॥

(प्रदीपः) वहद्गु इति। अस्य कालविशेषवृत्तित्वप्रदर्शनार्थमुपक्षेपः ॥

(उद्योतः) तिष्ठद्गु कालविशेष इत्युक्तत्वाद्वहद्गुवत्संगतमत आह—अस्य कालविशेषेति। वार्तिकमुपलक्षणमिति भावः। कालेऽन्यपदार्थे समासः ॥

(१२४१ वार्तिकम् ॥ २ ॥)

॥ * ॥ खलेयवादीनि प्रथमान्तान्यन्यपदार्थे ॥ * ॥

(व्याख्याभाष्यम्)

खलेयवादीनि प्रथमान्तान्यन्यपदार्थे समस्यन्त इति वक्तव्यम्। खलेयवम्। खलेबुसम्। लूनयवम्। पूनयवम्। पूयमानयवम्॥ तिष्ठद्गुप्रभृतीनि च॥ १६॥

(प्रदीपः) **खलेयवादीनीति**। अव्यतिरिक्त एव प्रातिपदिकार्थे एषां प्रयोगः कर्तव्यो नान्यत्रेति भावः॥ **अन्यपदार्थ इति**। न काल एव अपितु अन्यत्रापीत्यर्थः॥ १६॥

(उद्द्योतः) ननु व्यतिरिक्ते प्रातिपदिकार्थे कथं प्रथमान्तान्येव प्रयोज्यानीत्यत आह—**अव्यतिरिक्त एवेति**। भेदान्वयायोग्य इत्यर्थः। खलेयवादीन्यन्यपदार्थे समस्यन्ते तानि च समस्तानि प्रथमान्तान्येव प्रयोक्तव्यानीत्यर्थो वार्त्तिकस्येति बोध्यम्॥ ननु तिष्ठद्गवादीनामपि कालरूपान्यपदार्थ एव वृत्तेः किं विशेषोक्त्येत्यत आह—**न काल एवापितिवति**। स्वाम्यादावपीत्यर्थः॥ १६॥

(२३४ अव्ययीभावसंज्ञासूत्रम् ॥ २।१।२ आ. १३ सू.)

३६६ पारेमध्ये षष्ठ्या वा ॥ २।१।१७ ॥

(वावचनप्रयोजनाधिकरणम्)

(आक्षेपभाष्यम्)

वावचनं किमर्थम्?॥

(प्रदीपः) **पारे**॥ १७॥ **वावचनमिति**। महाविभाषयैव च वाक्यस्य षष्ठीसमासस्य च सिद्धत्वादिति भावः॥

(आक्षेपबाधकभाष्यम्)

विभाषा समासो यथा स्यात्। समासेन मुक्ते वाक्यमपि यथा स्यात्—पारं गङ्गाया इति॥

(प्रदीपः) इतरो न्यायप्रपञ्चार्थं स्ववाचा वा जल्पयितुं स्वाशयमप्रकाशयन्नाह—**विभाषेति**॥

(उद्द्योतः) **पारेमध्ये**॥ १७॥ **स्ववाचेति**। जल्पनापेक्षया करणे तृतीया। सिद्धान्ती उभयत्रापि स्वपदार्थः। पुनर्यदि मां प्रक्ष्यति तदा स्वाशयं वक्ष्यामीत्याशयेनेति भावः॥

(आक्षेपसाधकभाष्यम्)

नैतदस्ति प्रयोजनम्। प्रकृता महाविभाषा। तया वाक्यमपि भविष्यति॥

(आक्षेपबाधकभाष्यम्)

इदं तर्हि प्रयोजनम्। अव्ययीभावेन मुक्ते षष्ठीसमासो यथा स्यात्—गङ्गापारमिति॥

(आक्षेपसाधकभाष्यम्)

एतदपि नास्ति प्रयोजनम्। अयमपि विभाषा, षष्ठीसमासोपि, तावुभौ वचनाद्भविष्यतः॥

(प्रदीपः) **अयमपीति**। षष्ठीसमासे प्राप्ते अव्ययीभाव आरभ्यते स नित्यं बाधकः प्राप्त इति महाविभाषाधिकाराद्विकल्पेन बाधको भवतीति पक्षे षष्ठीसमासः सिध्यति सोऽपि विकल्पेन विधीयत इति वाक्यमपि भविष्यतीत्यर्थः॥

(उद्द्योतः) **विकल्पेन बाधक इति**। वृत्तिविवर्तनवादिनां विधेयसंज्ञाविशेषणं विभाषाधिकारः। तत्र यत्र संज्ञान्तरप्राप्तिस्तत्र साऽभ्यनुज्ञायते, यत्र न तत्र वाक्यमेवेत्यभिप्रायः॥

(समाधानभाष्यम्)

अत उत्तरं पठति—

(१२४२ वार्तिकम् ॥ १ ॥)

॥ * ॥ पारेमध्ये षष्ठ्या वावचनम् [अवचने हि षष्ठीसमासाभावो यथैकदेशिप्रधाने] ॥ * ॥

(व्याख्याभाष्यम्)

पारेमध्ये षष्ठ्या वेति वक्तव्यम्॥ अवचने हि षष्ठीसमासाभावो यथैकदेशिप्रधाने। अक्रियमाणे हि वावचने षष्ठीसमासस्याभावः स्याद्॥ यथैकदेशिप्रधाने। तद्यथा—एकदेशिसमासेन मुक्ते षष्ठीसमासो न भवति॥ किं पुनः कारणमेकदेशिसमासेन मुक्ते षष्ठीसमासो न भवति?। समासतद्धितानां वृत्तिर्विभाषा, वृत्तिविषये नित्योपवादः॥ इह पुनर्वावचने क्रियमाणे एकया वृत्तिर्विभाषा, अपरया वृत्तिविषये नित्योऽपवादः॥

(प्रदीपः) **अत उत्तरमिति**। एतस्मात् पक्षादुपरीत्यर्थः॥ **वक्तव्यमिति**। कृत्याश्चेत्यावश्यके कृत्यः॥ **एकदेशिप्रधान इति**। ननु पूर्वकाय इत्यादौ पूर्वपदार्थ एकदेशः प्रधानम्, न त्वेकदेशी॥ एवं तर्हि—एकदेशिनोनूद्यमानत्वादप्राधान्यं समासस्य तु विधेयत्वात् प्राधान्यम्। तत्रैकदेशिनः प्रधानमिति षष्ठीसमासेन समास उच्यते। अथ वा प्राधान्येन निमित्तत्वं लक्ष्यत इति बहुव्रीहावपि न दोषः॥ **समासतद्धितानामिति**। तुल्यन्यायत्वाद्विचाराय तद्धिता अपि निर्दिष्टाः। इह वाक्येनाभिधाने प्राप्ते वृत्तिरारभ्यमाणा वाक्यस्य बाधिका प्राप्नोतीति विकल्पेन वाक्यस्य पक्षेनुज्ञानं क्रियते॥ तत्रापवादेपि विकल्पेन विधीयमाने विकल्पो वाक्यस्यैवानुज्ञानं करोतीति उत्सर्गस्य नित्येन बाधेन भाव्यम्। तत्र वाग्रहणेनोत्सर्गोपि पक्षे अभ्यनुज्ञायत इति त्रैरूप्यं सिध्यति॥

एकयेति । विभाषयेत्यर्थः ॥ अपरयेति । इदमेव वावचनमुद्दिश्यतोन्यतरस्यामित्यन्यतरस्यांग्रहणं च ज्ञापकम्— यत्रोत्सर्गापवादौ वृत्तिषु विभाषा, तत्रापवादेन मुक्त उत्सर्गो न भवतीति ॥

(उद्योतः) एतस्मादिति । एतस्माद् वावचनं किमर्थमिति पूर्वपक्षाद् उपरि तदुत्तरकाले तत्समाधानभूतं वार्तिकं पठतीत्यर्थः ॥ सूत्रकारेण वाग्रहणस्य कृतत्वाद् वक्तव्यम् इत्यसंगतमित्यत आह— आवश्यके कृत्य इति ॥ समास उच्यते इति । एकदेशिनः प्रधाने विधीयमाने एकदेशिघटितसमुदायस्य विधीयमाने समास इत्यर्थ इति भावः ।. भाष्ये—वृत्तिर्विभाषेति । वृत्तिरेकार्थीभावः । अयं भावः—अपपरीत्यादौ समास इति अनुवृत्तम्, समर्थ इति च परिभाषयोपस्थितम् । तत्र लोकसिद्धैकार्थीभावः कास्ति, क नेति ज्ञातुमसमर्थानां बालानां स्फुटबोधनाय तत्र तत्र सूत्रे समासादिसंज्ञादिवदेकार्थीभावरूपसामर्थ्यमपि विधेयम् । विभाषाग्रहणं च सामर्थ्येनैव संबध्यते व्याख्यानात् । सामर्थ्ये समासविकल्पानिष्टेश्च 'सुबन्तं श्रितादिभिः सहोच्चार्यमाणं वा समर्थं भवति, समर्थं च समाससंज्ञं भवति' इत्यर्थः । निषेधसूत्रैरपि समासनिषेधे सन्नियोगशिष्टन्यायेन सामर्थ्यनिषेधोपि, सामर्थ्यस्यैव वा निषेधः ॥ इह पुनर्वावचनं तु सामर्थ्यादेकार्थीभाव एव संज्ञाया विकल्पबोधकमिति ध्वनयन्नाह—वृत्तिरारभ्यमाणेति ॥ वाक्यस्य । वाक्यविषयव्यपेक्षायाः ॥ वृत्तिषु । एकार्थीभावविषयेषु ॥ विभाषेति । महाविभाषया विकल्पितावित्यर्थः ॥ न भवतीति । महाविभाषा विशेषणीभूतसामर्थ्येनैव संबध्यत इति ज्ञाप्यत इति तात्पर्यम् ॥

(एकारान्तनिपातनाधिकरणम्)

(१२४३ वार्तिकम् ॥ २ ॥)

॥ * ॥ एकारान्तनिपातनं च ॥ * ॥

(व्याख्याभाष्यम्)

एकारान्तनिपातनं च कर्तव्यम् । पारेगङ्गमिति ॥

(निपातननिराकरणभाष्यम्)

न कर्तव्यम् । सप्तम्या अलुका सिद्धम् ॥

(प्रदीपः) सप्तम्या अलुकेति । तत्पुरुषे कृतीति बहुलग्रहणादिति भावः ॥

(निपातनावश्यकताभाष्यम्)

भवेत् सिद्धं यदा सप्तमी । यदा त्वन्या विभक्तयस्तदा न सिध्यति ॥ पारेमध्ये ॥ १७ ॥

(प्रदीपः) यदा त्वन्या इति । पारेगङ्गादागत इत्यादौ सप्तम्यर्थाभावात् सप्तम्यभावः ॥ १७ ॥

(उद्योतः) सप्तम्यर्थाभावादिति । गङ्गायाः पारादिति हि तत्रार्थः ॥ १७ ॥

(२३५ अव्ययीभावसंज्ञासूत्रम् ॥ २। १। २। आ. १४ सू.)

३६८ नदीभिश्च ॥ २।१।१९ ॥

(समाहारमात्रविषयकत्वाधिकरणम्)

(१२४४ वार्तिकम् ॥ १ ॥)

॥ * ॥ नदीभिः संख्यासमासेऽन्यपदार्थे प्रतिषेधः ॥ * ॥

(व्याख्याभाष्यम्)

नदीभिः संख्यासमासेऽन्यपदार्थे प्रतिषेधो वक्तव्यः । द्वीरावतीको देशः । त्रीरावतीको देशः । "नदीभिः संख्या" इति प्राप्नोति ॥

(प्रदीपः) नदीभिः ॥ १९ ॥ अर्थविशेषमनुपादाय पूर्वपदोत्तरपदमात्रनिर्देशेन समासोयं विधीयमानो द्विगोरिव बहुव्रीहेरपि बाधकः स्यादिति नदीभिरिति वार्तिकारम्भः ॥

(उद्योतः) नदीभिः ॥ १९ ॥ भाष्ये—अन्यपदार्थे इति । समाहारातिरिक्ते इत्यर्थः ॥ तद्ध्वनयन्नाह—द्विगोरिवेति । समाहारद्विगोरिवेत्यर्थः । परस्यापि बहुव्रीहेरनवकाशत्वाद्बाध्यसामान्यचिन्तापक्षे बाधकः स्यादिति भावः ॥

(वार्तिकप्रत्याख्यानभाष्यम्)

न वक्तव्यः । इह कश्चित्समासः पूर्वपदार्थप्रधानः । कश्चिदुत्तरपदार्थप्रधानः । कश्चिदन्यपदार्थप्रधानः । कश्चिदुभयपदार्थप्रधानः । पूर्वपदार्थप्रधानोऽव्ययीभावः । उत्तरपदार्थप्रधानस्तत्पुरुषः । अन्यपदार्थप्रधानो बहुव्रीहिः । उभयपदार्थप्रधानो द्वन्द्वः । न चात्र पूर्वपदार्थप्राधान्यं गम्यते ॥

(प्रदीपः) न वक्तव्य इति । भाष्यकारो वार्तिकं प्रत्याचष्टे । पूर्वाचार्यविहितगुरुसंज्ञाश्रयणाद्यदुपाधीनां पूर्वाचार्याः संज्ञां व्यधिषत तदुपाधीनामेवैता भवन्ति ॥ न चात्रेति । द्वीरावतीक इत्यादौ ॥ ननु पञ्चनदं द्वियमुनमित्यादौ मूलोदाहरणेपि पूर्वपदार्थप्राधान्यं नास्ति । समाहारो ह्यत्र समासार्थः । स च यदि समाहरणं समाहार इति भावरूपस्तदान्यपदार्थप्राधान्यम् । अथ समाह्रियत इति समाहारस्तथापि द्वेयमुने समाहृते द्वियमुनमिति पूर्वपदार्थविशिष्ट उत्तरपदार्थः प्रधानम् ॥ नैष दोषः । समाह्रियमाणार्थः समाहारः । तत्र पूर्वं द्विशब्दार्थप्रक्रमे 'के द्वे' इत्याकाङ्क्षायां यदा यमुने इत्युच्यते, तदोत्तरपदार्थस्य विशेषणत्वं विशेष्यत्वं पूर्वपदार्थस्य ॥ अथवा वृत्तिविषये द्व्यादयः संख्यानमात्रे वर्तन्त इति यमुनयोर्द्वित्वमित्यत्रार्थे द्वियमुनशब्दो वर्तत इति भवत्येव पूर्वपदार्थप्राधान्यम् ॥

(उद्योतः) ननु पूर्वपदार्थप्राधान्ये एवाव्ययीभाव इत्यत्र न मानमत आह—पूर्वाचार्येति ॥ गुरुसंज्ञया प्रकृतार्थलाभं दर्श-

यति—**यदुपाधीनामिति** । उपाधिश्चात्र तत्तदर्थप्रधानत्वमेव । एवं च तत्कृतमहासंज्ञयाचार्येण व्यवहारात्तदुक्तार्थोस्यानुमत इति ज्ञायत इति भावः ॥ **समाह्रियमाणार्थः समाहार इति** । समाहारशब्दः कर्मव्युत्पन्न एवेत्यर्थः ॥ **तदोत्तरपदार्थस्येति** । ननु परिच्छेदकत्वरूपं विशेषणत्वं परिच्छेद्यत्वरूपं विशेष्यत्वं यद्यपि तत्रायाति तथापि विषयताविशेषरूपं तत्पूर्वपदार्थस्य दुर्लभम्, गुणद्रव्ययोर्द्रव्यस्यैव विशेष्यत्वात् ॥ पूर्वपदार्थप्राधान्यमित्यादौ च प्राधान्यं विषयताविशेषरूपविशेष्यत्वमेव विवक्षितमन्यत्र सर्वत्र तस्यैव संभवादित्यरुचेराह—**अथवेति** । इदमपि प्रौढिवादः । पञ्चनदीसमूहस्य पञ्चतोत्यन्तभेदाभावात्पूर्वपदार्थप्रधानत्वमपि [तत्र] वक्तुं शक्यम् । अत्र तु न तत्सम्भवोपीति भाष्याशय इति तत्त्वम् ॥

(आक्षेपभाष्यम्)

ननु च यद्येनोच्यते स तस्यार्थो भवति । अत्र च वयमेताभ्यां पदाभ्यामेतमर्थमुच्यमानं पश्यामः ॥

(प्रदीपः) इदानीं चोदकोन्यपदार्थमाक्षिपति—**नन्विति** । अयं भावः—द्वीरावतीक इति देशविशेषोभिधीयते । स च पूर्वोत्तरपदयोः सहितयोरर्थ इति द्वाभ्यामप्यसौ व्यपदिश्यते । ततः पूर्वपदार्थत्वाद्देशस्य तस्य प्राधान्यात् प्राप्नोत्यव्ययीभावः ॥

(उद्द्योतः) **द्वाभ्यामप्यसाविति** । इयमपि रीतिर्द्वियमुनमित्यादौ वक्तुं युक्ता ॥

(आक्षेपबाधकभाष्यम्)

एतदेव न जानीमः—यद्येनोच्यते स तस्यार्थ इति ॥ अपि चान्यपदार्थप्रधानता न कल्पेत—चित्रगुः शबलगुरिति । किं कारणम् ? । अत्रापि हि वयमेताभ्यां शब्दाभ्यामेतमर्थमुच्यमानं पश्यामः ॥

(प्रदीपः) **एतदेवेति** । सिद्धान्तवादी । अस्याभिप्रायः—समासेनान्यपदार्थः प्रतीयते, नतु पूर्वोत्तरपदाभ्याम् । तयोरन्वयव्यतिरेकाभ्यामर्थान्तराभिधायित्वावधारणात् । तथा हि—द्विशब्दो द्वित्वावच्छिन्नं संख्येयमात्रमाह, न देशम्; इरावतीशब्दोपि नदीविशेषमाह, न देशमिति द्विशब्दो देशस्यावाचक इति कथं पूर्वपदार्थप्राधान्यमभिधीयते ॥ **अपि चेति** । त्वत्पक्षाभ्युपगमो दोषवानित्यर्थः ॥

(उद्द्योतः) भाष्ये—**एतदेवेति** । **यद्येनोच्यते** इत्यादिन्यायेन यत्पूर्वपदार्थप्राधान्यमुक्तं **एतदेव न जानीमः** अत्र न पश्याम इत्यक्षरार्थः । तदेवाह—**समासेनेति** ॥ **दोषवानिति** । त्वद्रीत्या विग्रहवाक्येपि समस्यमानपदाभ्यामेवार्थप्रतीतेर्बाह्यस्तवबहुव्रीहावप्यन्यपदार्थप्राधान्यं भज्येतेत्यर्थः ॥

(आक्षेपसाधकभाष्यम्)

यद्यप्येताभ्यां पदाभ्यामेषोर्थ उच्यते, अन्यपदार्थोपि तु गम्यते । तत्रान्यपदार्थाश्रयो बहुव्रीहिर्भविष्यति ॥

इहापि तर्हि यद्यप्यन्यपदार्थो गम्यते, स्वपदार्थोपि गम्यते । तत्र स्वपदाश्रयोऽव्ययीभावः प्राप्नोति ॥

(प्रदीपः) चोदकश्चोद्यमुद्भावितं परिहरति—**यद्यपीति** ॥ स एव परस्य चोद्यमापादयति—**इहापीति**—**प्राप्नोतीत्यन्तम्** । अयमभिप्रायः—पूर्वपदोत्तरपदव्यतिरेकेण समासाभावात् तयोरेव समुदितयोर्देशोर्थ इति पूर्वोक्तन्यायेन पूर्वपदस्याप्यसावर्थ इति प्राप्नोत्येवाव्ययीभावः ॥

(उद्द्योतः) भाष्ये—**अन्यपदार्थोपि त्विति** । विग्रहवाक्येन्यपदेन प्रतीयमानस्येह समासेन प्रतीयमानत्वादित्यर्थः ॥ सिद्धान्त्युक्तिस्यासंभवात् **इहापि तर्हीति** भाष्ये तर्हिशब्द एवमर्थे । तद्ध्वनयन्नाह—**स एव परस्येति** ॥ केचित्तु देशस्यान्यपदार्थत्वेपि तद्देशस्वरूपे द्वीरावतीरूपस्वपदार्थस्याप्यन्तर्भावात् तस्य च त्रिपदार्थानतिरेकेणान्यपदार्थघटकतया पूर्वपदार्थस्य समाहारे इव यथा कथंचित्प्रधानत्वसत्त्वाद्दुर्वारोऽव्ययीभाव इति भाष्यार्थमाहुः ॥

(समाधानभाष्यम्)

एवं तर्हीदमिह संप्रधार्यम्—अव्ययीभावः क्रियतां बहुव्रीहिरिति । बहुव्रीहिर्भविष्यति विप्रतिषेधेन ॥

(प्रदीपः) **एवं तर्हीति** । पुरस्तादपवादन्यायेनायं द्विगुमेव बाधते । बहुव्रीहिणा तु परत्वाद्बाध्यते । शेषग्रहणञ्च तत्र प्रत्याख्यातम् । त्रिकापेक्षो वा शेषः ॥

(उद्द्योतः) **शेषग्रहणं चेति** । अन्यथा तयोः पदयोरुक्तसमाससत्त्वाद्बहुव्रीहिर्न स्यादिति भावः ॥

(पूर्वपक्षिभाष्यम्)

भवेदेकसंज्ञाधिकारे सिद्धम्, परंकार्यत्वे तु न सिद्ध्यति । आरम्भसामर्थ्यादव्ययीभावः प्राप्नोति, परंकार्यत्वाच्च बहुव्रीहिः ॥

(उद्द्योतः) भाष्ये **भवेदेकसंज्ञाधिकार इति** । बाध्यविशेषचिन्तायामिति शेषः ॥ **परंकार्यत्वे तु न सिध्यतीति** । तत्र हि पाठे पूर्वयानवकाशया बाधे प्राप्ते परविधानार्थमिदम् । एवंच समाहारेपि द्विगुः सामर्थ्यादव्ययीभावश्चेत्येष्टव्यम् । एवं च पुरस्तादपवादन्यायाभावेन द्विग्वव्ययीभाववदन्यपदार्थविषये बहुव्रीह्यव्ययीभावावपि स्यातामिति भावः ॥

(सिद्धान्तिभाष्यम्)

परंकार्यत्वे च न दोषः। नदीभिः संख्यायाः समाहारेऽव्ययीभावो वक्तव्यः । स चावश्यं वक्तव्यः । सर्वमेकनदीतरं ॥ नदीभिश्च ॥ १९ ॥

(प्रदीपः) **एकनदीतर इति** । यदि समाहारग्रहणं न क्रियते तदा **पुरस्तादपवादा** इत्यनेन न्यायेनायं समासः **पूर्वकालैके**ति समासं बाधेत समाहारे। तु परत्वाद्विगुः स्यात् । ततश्चैकनदीत्यत्राव्ययीभावे कृते तन्निबन्धनो **नदीपौर्णमास्याग्रहायणीभ्य** इति वा टच् प्राप्नोति नपुंसकत्वं च। यस्तु **गोदावर्याश्च नद्याश्चे**त्यच्समासान्तः सोच्प्रत्यन्यवेत्यत्र योगविभागेन क्रियते स चेष्टप्रसिद्ध्यर्थ इति तत्पुरुषे प्रयोगादर्शनादेकनदीत्यत्र न प्रवर्तते । अव्ययीभावे तु पञ्चनदमित्यत्र भवत्येव । एकापूपीवत्समाहारविवक्षायामेकनदमेकनदीति भवतीत्याहुः ॥ १९ ॥

(उद्योतः) भाष्ये—सिद्धान्त्याह—**नदीभिः संख्यायाः समाहार** इति । **परंकार्य**मिति पाठे द्विगोः परत्राव्ययीभावप्रकरणं कार्यमित्यर्थः । एवं च द्विगुविषये न दोषः, अन्यपदार्थे तु प्राप्तिरेव नेति भावः ॥ **स चावश्यमिति** । **एका संज्ञे**ति पाठेपि समाहार इत्यवश्यं वाच्यमित्यर्थः ॥ भाष्ये तत्फलमाह—**सर्वमेकनदीतरइति** । तदभावे **पुरस्तादि**तिन्यायेन **पूर्वकालैके**ति बाधित्वानैवाव्ययीभावः स्यात् । तथा च तत्प्रयुक्तं **सर्वं** टच् नपुंसकत्वं चात्र स्यादिति भावः ॥ **सर्वमेकनदीतर** इति कस्यचित्पद्यस्य शेष इति बहवः । तॄधातोस्तर इति रूपम् ॥ **तीर** इति क्वचित्पाठः ॥ **इत्यत्र भवत्येवेति । नदीपौर्णमासीति** टजिति शेषः ॥ **एकापूपीवत् समाहारेति** । प्रत्यवयवमपूपत्वारोपेणेत्यर्थः ॥ **भवतीत्याहुरिति** । अत्रारुचिबीजं तद्वदत्र समाहारविवक्षायां मानाभाव इति ॥ १९ ॥

इति समासप्रकरणेऽव्ययीभावप्रकरणम् ॥

(अथ तत्पुरुषप्रकरणम्)

(२३६ द्विगोस्तत्पुरुषसंज्ञासूत्रम् ॥ २।१।२ आ. १५ सू.)

३७१ द्विगुश्च ॥ २।१।२२ ॥

(आक्षेपभाष्यम्)

द्विगोस्तत्पुरुषत्वे कानि प्रयोजनानि? ॥

(१२४५ समाधानवार्तिकम् ॥ १ ॥)

॥ * ॥ द्विगोस्तत्पुरुषत्वे समासान्ताः प्रयोजनम् ॥ * ॥

(व्याख्याभाष्यम्)

द्विगोस्तत्पुरुषत्वे समासान्ताः प्रयोजयन्ति— पञ्चगवं दशगवं पञ्चराजं दशराजम् ॥ द्विगुश्च॥२२ ॥

(प्रदीपः) **द्विगुः ॥२२॥ समासान्ता इति** । यद्यपि टजचावेव तत्पुरुषनिबन्धनौ पञ्चगवं द्व्यङ्गुलमिति, तथापि प्रकृतिभेदाद्बहुवचननिर्देशः ॥ **पञ्चराजमिति** । अकारान्तोत्तरपदत्वाभावात् स्त्रीत्वाभावः । यदा तु समासार्थोत्तरपदान्ताः समासान्ता इति पक्षस्तदा तु पात्रादित्वात् स्त्रीत्वाभावः ॥२२॥

(उद्योतः) **द्विगुश्च ॥ २२ ॥ पात्रादित्वादिति** । वस्तुत उत्तरपदावयवत्वपक्षो नास्त्येव **अन्त** इति सूत्रस्थभाष्यविरोधादिति **समासान्ता** इति शब्देन्दुशेखरे स्पष्टं निरूपितमस्माभिः ॥ २२ ॥

(२३७ तत्पुरुषसंज्ञासूत्रम् ॥ २ । १ । २ आ. १६ सू.)

३७२ द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः ॥ २।१।२३ ॥

(न्यूनतापूर्त्यधिकरणम्)

(१२४६ वार्तिकम् ॥ १ ॥)

॥ * ॥ श्रितादिषु गमिगाम्यादीनामुपसंख्यानम् ॥ * ॥

(व्याख्याभाष्यम्)

श्रितादिषु गमिगाम्यादीनामुपसंख्यानं कर्तव्यम् । ग्रामं गमी ग्रामगमी ग्रामं गामी ग्रामग्रामी ॥

(प्रदीपः) **द्वितीया ॥ २३ ॥ गमिगाम्यादीनामिति** । औणादिकानामन्येषां च संग्रहार्थमुभयोरुपादानम् ॥ **ग्रामगमीति । गत्यर्थकर्मणी**त्यत्र द्वितीयाग्रहणमपवादविषयेपि विधानार्थमिति कृत्प्रयोगे द्वितीयैव भवति इति षष्ठ्याः प्राप्तिरेव नास्तीति ये तस्या **अकेनो**रिति प्रतिषेधं वर्णयन्ति ते पूर्वापरविस्मरणशीलत्वादुपेक्ष्याः ॥ भाष्यकारेण तु **गत्यर्थ**सूत्रस्य प्रत्याख्यानात् कृत्प्रयोगे षष्ठ्येवेष्यत इति तद्दर्शने सौत्रः षष्ठीनिषेधः ॥

(उद्योतः) **द्वितीयाश्रिता ॥ २३ ॥ गमिशब्दो गमेरि**निरित्यौणादिकः । **गामी**ति वृद्धिर्बाहुलकात् ॥ **अन्येषां चेति** । **सनाशंसे**त्युप्रत्ययादीनामित्यर्थः । ओदनं बुभुक्षुः ओदनबुभुक्षुरित्युदाहरणम् ॥ उभयोरपि उणादिप्रत्ययान्तत्वेन कथमुभयोपादानेनान्येषां चेत्यर्थलाभ इति चिन्त्यम् । तस्मादादिग्रहणस्य प्रकारार्थत्वेन व्याख्यानादेतदर्थलाभो बोध्यः । उभयोपादानं तु स्पष्टार्थमेवेति परे॥ **पूर्वापरेति । गत्यर्थकर्मणीति**सूत्रस्थैतत्सूत्रस्थयोरित्यर्थः । **नास्ती**त्यन्तो गत्यर्थसूत्रस्थः । **अकेनोरिति प्रतिषेध** इत्यत्रत्यः । प्राप्तिरेव नास्तीति वदन्तो येत्र सूत्रे तस्याः प्रतिषेधं वर्णयन्ति ते इत्यन्वयः ॥ **सौत्रइति । अकेनो**रिति सूत्रविहित इत्यर्थः । एवं च **गत्यर्थकर्मणी**ति सूत्रस्थो ग्रन्थो वृत्तिकृतो भाष्यविरुद्धोपीति तात्पर्यम् ॥

(तत्पुरुषविधानानर्थक्यपरिहाराधिकरणम्)

(१२४७ वार्तिकम् ॥ २ ॥)

॥ * ॥ श्रितादिभिरहीने द्वितीयासमासवचनानर्थक्यं बहुव्रीहिकृतत्वात् ॥ * ॥

(व्याख्याभाष्यम्)

श्रितादिभिरहीनवाचिन्या द्वितीयायाः समासवचनमनर्थकम् ॥ किं कारणम् ? । बहुव्रीहिकृतत्वात् । इह—यः कष्टं श्रितः, कष्टमनेन श्रितं भवतीति तत्र बहुव्रीहिणा सिद्धम् ॥

(प्रदीपः) **श्रितादिभिरिति** । यः कष्टं श्रितः कष्टमनेन श्रितमिति बहुव्रीहिणैव विवक्षितार्थावगमादर्थरूपस्वरभेदाभावात् तत्पुरुषो न विधेय इत्यर्थः ॥ **अहीनवाचिन्या इति** । यः कष्टं श्रितः कष्टं तेन न हीनमित्यर्थ इति भावः । श्रयतिरत्र गतौ वर्तत इति गत्यर्थत्वात् कर्तरि क्तः । ततः श्रितपतितगतैः समासोयं न विधेयः । अतीतादिभिस्तु स्वरसिद्ध्यर्थो विधेयः । तर्हि तत्पुरुषे सति थाथादिस्वरेण भाव्यम् अतीतात्यस्तयोरहीन इति निषेधात् प्राप्तापन्नयोरहीने द्वितीयानुपसर्गे इति निषेधात् पूर्वपदप्रकृतिस्वरो नास्ति । बहुव्रीहौ तु पूर्वपदप्रकृतिस्वरेण भाव्यम् । यदा तु जातिकालसुखादीनि पूर्वपदानि तदा तत्रापि बहुव्रीहितत्पुरुषयोः स्वरभेदाभावः ॥ **बहुव्रीहिकृतत्वादिति** । बहुव्रीहिणा रूपस्य साधितत्वादित्यर्थः ॥

(उद्योतः) भाष्ये—**अहीनेद्वितीयेति** ॥ अहीनवाचकद्वितीयान्तस्येत्यर्थः ॥ **विवक्षितार्थावगमादिति** । कष्टकर्मकश्रयणकर्तृविशिष्टेर्थे उभाभ्यामपि प्रतिपाद्यत इत्यर्थः । बहुव्रीहौ श्रितादीनां पूर्वनिपातः स्यादिति तु न शङ्क्यं तत्प्रकरणानित्यत्वादिति बोध्यम् ॥ **तेन न हीनमिति** । न त्यक्तमित्यर्थः । यथा कान्तारमतीतेन कान्तारः ॥ **अतीतात्यस्तयोरिति** । यो हि कान्तारमतीतोत्यस्तो वा तेन कान्तारो हीनो भवतीति द्वितीयान्तस्य हीनवाचित्वादित्यर्थः । यद्यप्यत्राप्यनुपसर्ग इति निषेधोप्यस्ति तथाप्ययमप्यस्तीति अयमेवोक्तः ॥ **यदा त्विति** । वाजातादिष्विति वक्ष्यमाणत्वादिति भावः ॥ ननु समासवचनपक्षकानर्थकत्वानुमाने बहुव्रीहिकृतत्वहेतुर्व्यधिकरणोत आह—**बहुव्रीहिणेति** । एवं च बहुव्रीहिसिद्धस्वसाध्यरूपकत्वादिति हेतुरिति भावः ॥

(१२४८ बहुव्रीहिवादिवार्तिकम् ॥ ३ ॥)

॥ * ॥ अहीने द्वितीयास्वरवचनानर्थक्यं च ॥ * ॥

(व्याख्याभाष्यम्)

अहीने द्वितीयापूर्वपदं प्रकृतिस्वरं भवतीत्येतत्स्वरवचनमनर्थकम् ॥ किं कारणम् ? । बहुव्रीहिकृतत्वादेव ॥

(उद्योतः) भाष्ये—**इत्येतत्स्वरवचनमिति** । एतदर्थप्रतिपादकं स्वरस्य वचनमहीने द्वितीयेति सूत्रमित्यर्थः ॥

(१२४९ तत्पुरुषवादिवार्तिकम् ॥ ४ ॥)

॥ * ॥ जातिस्वरप्रसङ्गस्तु ॥ * ॥

(व्याख्याभाष्यम्)

जातिस्वरस्तु प्राप्नोति—ग्रामगतः अरण्यगत इति "जातिकालसुखादिभ्योनाच्छादनात् क्तोऽकृतमितप्रतिपन्नाः" इति ॥

(प्रदीपः) **जातिस्वरप्रसङ्ग इति** ॥ यदि बहुव्रीहिरेव क्रियते तदा **जातिकाले**त्यन्तोदात्तत्वं प्राप्नोतीत्यर्थः ॥

(उद्योतः) अन्तोदात्तत्वमिति । तदेवेत्यर्थः । इष्यते तु समासभेदेन स्वरद्वयमिति भावः ॥

(१२५० बहुव्रीहिवादिवार्तिकम् ॥ ५ ॥)

॥ * ॥ तत्र जातादिषु वावचनात्सिद्धम् ॥ * ॥

(व्याख्याभाष्यम्)

यदेतद् "वा जाते" इति, एतद् "वा जातादिषु" इति वक्ष्यामि । इमे जातादयो भविष्यन्ति ॥

(प्रदीपः) बहुव्रीहिवादी स्वरदोषं परिहरति—**तत्रेति** ॥ **"वा जाते"** इति न्यासमपास्य **वा जातादिष्विति** वक्ष्यते तेन पक्षे अन्तोदात्तत्वं पक्षे पूर्वपदप्रकृतिस्वरत्वमिति स्वरद्वयसिद्धिः ॥ **इमे इति** । श्रितगतपतितशब्दाः । ततश्चाहीने द्वितीयेति न वक्तव्यमिति लाघवं भवति ॥

(आक्षेपभाष्यम्)

ननु च भेदो भवति—बहुव्रीहौ सति समासान्तोदात्तत्वेनापि भवितव्यं पूर्वपदप्रकृतिस्वरत्वेनापि । तत्पुरुषत्वे सति पूर्वपदप्रकृतिस्वरत्वेनैव ॥

(प्रदीपः) तत्पुरुषवाद्याह—**ननु चेति** ॥

(आक्षेपबाधकभाष्यम्)

नास्ति भेदः । योपि हि तत्पुरुषमारभते न तस्य दण्डवारितो बहुव्रीहिः । तत्र तत्पुरुषे सति द्वौ समासौ द्वौ स्वरौ, बहुव्रीहौ सति एकः समासो द्विस्वरत्वम् ॥

(प्रदीपः) बहुव्रीहिवाद्याह—**नास्ति भेद इति** ॥ **द्वौ स्वराविति** । तत्पुरुषे अहीने द्वितीयेति पूर्वपदप्रकृतिस्वरः, बहुव्रीहौ जातिकालेत्यन्तोदात्तत्वम् ॥ **द्विस्वरत्वमिति** । वा जातादिष्विति सूत्रन्यासेन ॥

(तत्पुरुषसाधकज्ञापकवादिभाष्यम्)

एवं तर्हि सिद्धे सति यत्तत्पुरुषं शास्ति, तज्ज्ञापयत्याचार्यः 'समानार्थे केवलं विग्रहभेदाद्यत्र तत्पुरुषः प्राप्नोति बहुव्रीहिश्च, तत्र तत्पुरुष एव भवति' । किमेतस्य ज्ञापने प्रयोजनम्? । राज्ञः सखा राजसखः, राजा सखा अस्येति बहुव्रीहिर्न भवति॥

(प्रदीपः) **एवं तर्हीति** । ततश्च बहुव्रीह्यभावात् कष्टश्रित इत्यादावहीने द्वितीयेति पूर्वपदाद्युदात्तत्वं भवति । **निष्ठा च द्व्यजनादि**त्याद्युदात्तत्वात् कष्टशब्दस्य । न तु जातिलक्षणबहुव्रीहिनिबन्धनमन्तोदात्तत्वम् । अव्यविकन्यायश्चानेन ज्ञापकेन स्मारितः ॥ **राज्ञः सखेति** । सख्युरुभयाधिष्ठानत्वाद्राजा सखास्येत्ययमर्थोऽन्तर्भूत इति बहुव्रीहिः स्यात् अस्मात्तु ज्ञापकान्न भवति ॥

(उद्योतः) **पूर्वपदाद्युदात्तत्वमिति** । तदेवेत्यर्थः ॥ **अन्तोदात्तत्वमिति** । तदपीत्यर्थः ॥ **अव्यविकेति** । अवेर्मांसमिति विग्रह एव अविकादेव च प्रत्ययोत्पत्तिराविकमिति, तथा कष्टं श्रितमनेनेति वाक्यमेव । कष्टं श्रित इति विग्रहे एव समास इत्यर्थः ॥ ननु राज्ञः सखेत्यस्य राजनिरूपितसखित्ववानर्थः । बहुव्रीहौ राजाभिन्नसखिसम्बन्धीति बोधेऽन्यनिरूपितं सखित्वं राजनि प्रतीयते इति समानार्थकत्वाभावात् कथं पूर्वोक्तज्ञापकेनात्र समासाभाव इत्यत आह—**सख्युरुभयेति** ॥

(बहुव्रीहिसाधकापवादवादिभाष्यम्)

नैतज्ज्ञापकसाध्यम् ॥ 'अपवादैरुत्सर्गा बाध्यन्ते' इति बाधकेनानेन भवितव्यं सामान्यविहितस्य विशेषविहितेन ॥ अथ न सामान्यविहितः ॥

(प्रदीपः) अत्र कश्चिदुत्सर्गापवादन्यायेन बहुव्रीह्यभावं मन्यमान आह—**नैतदिति** । अर्थाभेदे बहुव्रीहौ प्राप्ते तत्पुरुषस्यारम्भात् ॥ ज्ञापकवाद्यपवादवादिनोश्चात्राहोपुरुषिकैव । तत्पुरुषारम्भे बहुव्रीहिबाधलक्षणं तु फलं न भिद्यते ॥ **विशेषविहितेनेति** । श्रिताद्युपादानेन विधानादस्य विशेषविहितत्वम् ॥ **अथ नेति** । कष्टं श्रित इति स्वपदार्थे तत्पुरुषविधानात्तत्र च बहुव्रीहेरप्राप्तत्वान्नास्ति सामान्यविहितत्वम् । अन्तर्भूतश्चार्थो न शब्दसंस्कारे निमित्तं किन्तु शब्दवाच्य एव ॥

(उद्योतः) कश्चिदुत्सर्गापवादभावं मन्यमानो ज्ञापकं दूषयति—**नैतज्ज्ञापकेति** । एतत् उक्तं वस्तु **ज्ञापकसाध्यं न** ज्ञापकस्यस्यैवासम्भवादित्यर्थः। एवं च श्रितादिविषयतत्पुरुषेणानवकाशतया बहुव्रीहिबाधे कष्टश्रितादौ पूर्वपदाद्युदात्तत्वमेव भवति । एवं च राजा सखास्येति विग्रहे बहुव्रीहिः स्यादेव, षष्ठीति शास्त्रस्य राजपुरुषादौ सावकाशत्वेन बहुव्रीहिबाधकत्वाभावादिति भावः । किं च उभयोश्चरितार्थयोः परत्वाद्बहुव्रीहिरेव स्यात् षष्ठीतत्पुरुषो न स्यादेव । टज्विधानं तु सुन्दरसख इत्यादौ कर्मधारये चरितार्थमित्याशयः ॥ एवं च ज्ञापकवाद्यपवादवादिनोरत्राहोपुरुषिकैव । तत्पुरुषारम्भे बहुव्रीहिबाधलक्षणं तु फलं न भिद्यते इति कैयटाशयश्चिन्त्यः ॥ **स्वपदार्थे तत्पुरुषेति** । स्वपदार्थप्रधानविग्रह इत्यर्थः । बहुव्रीहिस्तु नैवंविधे विग्रहे, किन्तु कष्टं श्रितमनेनेति विग्रहे ॥ एवं च विषयभेदान्न सामान्यविहितत्वं बहुव्रीहेरिति भावः ॥ ननु कष्टं श्रित इत्यत्र बहुव्रीहिविग्रहार्थोऽप्यन्तर्भूत इत्यत आह—**अन्तर्भूतश्चार्थ इति** ॥

(तत्पुरुषसाधकसिद्धान्तिभाष्यम्)

यदुच्यते—बहुव्रीहिकृतत्वादिति ॥ एतदयुक्तम् । अस्ति खल्वपि विशेषो बहुव्रीहेस्तत्पुरुषस्य च ॥

(प्रदीपः) **यदुच्यत इति** । अर्थभेदात् श्रितादिग्रहणं कृतमिति भावः ॥ ननु कष्टश्रित इति समासप्रयोगे लोके विग्रहवाक्याप्रयोगात् तात्पर्याभेदादस्ति बहुव्रीहिकृतत्वमित्याशङ्क्याह—**अस्ति खल्वपीति** ॥

(उद्योतः) **अर्थभेदादिति** । एवं च सूत्रसार्थक्यात् त्वदीयज्ञापकत्वमप्यसंगतमिति भावः ॥ **लोके विग्रहेति** । समासप्रयोगे कर्तव्ये लोके विग्रहवाक्यस्याप्रयोगात्तत्पुरुषत्वबहुव्रीहित्वानवगमादिति भावः ॥ अर्थद्वयबोधेप्याह—**तात्पर्येत्यादि** । एवं च ज्ञापकत्ववादिनोपवादत्ववादिनश्च खण्डनायास्तिखल्वपीत्यादि सिद्धान्तिनो ग्रन्थ इति भावः ॥

(आक्षेपभाष्यम्)

किं शब्दकृतः, अथार्थकृतः? ॥

(प्रदीपः) पूर्वोक्तेन न्यायेनार्थरूपस्वरेषु विशेषमपश्यन् पृच्छति—**किमिति** ॥

(समाधानभाष्यम्)

शब्दकृतश्चार्थकृतश्च । शब्दकृतस्तावत्—बहुव्रीहौ सति कपा भवितव्यम् । तत्पुरुषे सति न भवितव्यम् ॥ अर्थकृतः—तत्पुरुषे सति रुहादीनां क्तः कर्तरि भवति धात्वर्थस्यानपवर्गे—आरूढो वृक्षं देवदत्तः । बहुव्रीहौ व्यपवृक्ते कर्मणि भवति—आरूढो वृक्षो देवदत्तेनेति ॥ अन्यथाजातीयकः खल्वपि प्रत्यक्षेणार्थसंप्रत्ययः अन्यथाजातीयकः संबन्धात् । राज्ञः सखा राजसखः । संबन्धादेतद्गन्तव्यम्—नूनं राजाप्यस्य सखेति ॥ उभयं खल्वपीष्यते—'स्वस्ति सोमसखा', 'पुनरेहि गवांसख' इति ॥ द्वितीया श्रिता० ॥ २३ ॥

(प्रदीपः) **बहुव्रीहाविति** । शेषाद्विभाषेत्यनेन कष्टश्रितक इति ॥ **तत्पुरुष इति** । कष्टश्रित इत्यादौ ॥ **रुहादीनामिति** । आदिशब्दः प्रकारे। तेन गत्यर्थादयोपि गृह्यन्ते ॥ **धात्वर्थस्येति** । सर्वस्य धात्वर्थस्यानिष्ठितत्वेपि तदेकदेश-

भूतत्वाश्रयेणारोहणक्रियाविशिष्टे एव वृक्षमारूढ इति शब्दशक्तिस्वाभाव्यादिदमभिधीयते । यथा बद्धो बन्धनमनुभवन्नेवोच्यते तथा कष्टश्रित इति कष्टमनुभवन्नेवोच्यते ॥ **व्यपवृक्त इति** । सर्वात्मना धात्वर्थे निष्ठित इत्यर्थः । यथा भुक्त ओदन इति भुजिक्रियायाः समाप्तौ प्रयुज्यते ॥ भेदान्तरमप्याह—**अन्यथेति** ॥ **प्रत्यक्षेणेति** । शब्दादव्यवधानेनेत्यर्थः । अव्यवधानोपलक्षणत्वात्प्रत्यक्षस्य ॥ ज्ञापकफलमपि निराकर्तुमाह—**उभयमिति** ॥ **सोमसखेति** । बहुव्रीहित्वात् समासान्ताभावः ॥ **गवांसख इति** । तत्पुरुषत्वात् समासान्तस्तत्पुरुषे कृति बहुलमिति **षष्ठ्या आक्रोश** इति वा षष्ठ्या अलुक् ॥ २३ ॥

(उद्द्योतः) भाष्ये—**बहुव्रीहौ सतीति** । तस्मिन्नेव सतीत्यर्थः ॥ **तत्पुरुषे सतीति** । तस्मिन्नपि सतीत्यर्थः ॥ **न भवितव्यमिति** । पूर्वपदप्रकृतिस्वरसन्नियोगेन न भवितव्यमित्यर्थः ॥ तत्पुरुषारम्भे वा जातादिष्विव्त्यस्याभावाद्ग्रामगत इत्यादावन्तोदात्तत्वमेवेति बहुव्रीहाविति पूर्वपदप्रकृतिस्वरसंनियोगेन न कदापि कप् । तदनारम्भे तु वा जातादिष्वित्यारम्भात्पक्षे बहुव्रीहावपि पूर्वपदप्रकृतिस्वरसत्त्वात्तत्संनियोगेनापि कवापत्तिरिति भावः ॥ कैयटोक्तोदाहरणे समासद्वयेपि पूर्वपदप्रकृतिस्वरसत्वात् कपो वैकल्पिकत्वाच्च न विशेष इति चिन्त्यम् ॥ भाष्ये—**अर्थकृतइति** । अर्थभेदे सत्येकेनापरस्य न गतार्थतेति भावः ॥ **धात्वर्थस्यानपवर्गे इति** । सर्वधात्वर्थासमाप्तौ धात्वर्थाविष्ट एव कर्त्तरि एकदेशस्य भूतत्वाश्रयेण क्तो भवति तत्पुरुषे । बहुव्रीहौ तु सर्वधात्वर्थसमाप्तौ धात्वर्थानाविष्टे कर्मण्येव क्त इति विशेष इत्यर्थः ॥ **अन्यथाजातीय इति** । शाब्दत्वाक्रान्त इत्यर्थः ॥ **अन्यथाजातीयकः सम्बन्धादिति** । आनुमानिक इत्यर्थः ॥ नन्वेवं राज्ञः सखाऽस्येति विग्रहे बहुव्रीहिः स्यादत आह—**उभयं खल्वपीति** ॥ २३ ॥

(२३८ तत्पुरुषसंज्ञासूत्रम् ॥ २ । १ । २ आ. १७ सू.)

३७४ खट्वा क्षेपे ॥ २।१।२५ ॥

(उदाहरणनिर्णयाधिकरणम्)

(आक्षेपभाष्यम्)

किमुदाहरणम्? ॥

(प्रदीपः) **खट्वा** ॥ २५ ॥ खट्वारूढ इत्यत्र क्षेपहेतोर्धर्मस्यानिर्देशात् क्रियाकारकसंबन्धमात्रावगमात् पृच्छति—**किमुदाहरणमिति** ॥

(समाधानभाष्यम्)

खट्वारूढः ॥

(प्रदीपः) समासस्य क्षेपोर्थः स चात्रास्तीत्याह—**खट्वारूढ इति** ॥

(आक्षेपभाष्यम्)

क्षेप इत्युच्यते । कः क्षेपो नाम ? ॥

(समाधानभाष्यम्)

अधीत्य स्नात्वा गुरुभिरनुज्ञातेन खट्वारोढव्या । य इदानीमतोन्यथा करोति स उच्यते खट्वारूढोयं जाल्मो नातिव्रतवान् ॥ खट्वा क्षेपे ॥ २५ ॥

(प्रदीपः) **अधीत्येति** । ब्रह्मचारिणा वेदाध्ययने निष्पादिते गृहस्थाश्रमः कर्तव्यः ॥ **अन्यथेति** । असमाप्तेऽध्ययने भूमिशयनार्हो यः खट्वारोहणं करोतीत्यर्थः । खट्वारोहणं चाविनयोपलक्षणार्थमित्याह—**नातिव्रतवानिति** ॥ २५ ॥

(उद्द्योतः) **खट्वा** ॥ २५ ॥ **अधीत्यस्नात्वेति** । अधीत्य स्नात्वा चेत्यर्थः ॥ २५ ॥

(२३९ तत्पुरुषसंज्ञासूत्रम् ॥ २ । १ । २ आ. १८ सू.)

३७७ अत्यन्तसंयोगे च ॥ २।१।२८ ॥

(१२५१ वार्तिकम् ॥ १ ॥)

॥ * ॥ अत्यन्तसंयोगे समासस्याविशेषवचनात् क्तेन समासवचनानर्थक्यम् ॥ * ॥

(व्याख्याभाष्यम्)

अत्यन्तसंयोगे समासस्याविशेषवचनात् क्तान्तेन चाक्तान्तेन च, "कालाः क्तेन" इत्येतत्समासवचनमनर्थकम् । "अत्यन्तसंयोग" इत्येव सिद्धम् ॥

(प्रदीपः) **अत्यन्त** ॥ २८ ॥ **काला इति** पृथग्योगेन क्तान्तेन समासविधानं न कर्तव्यम् । **काला अत्यन्तसंयोग** इत्येक एव योगः कर्तव्यः । तत्र च **क्तेनेत्यस्य** निवृत्तत्वात् सर्वत्र समासः सिध्यतीति नन्वाह—**अत्यन्तसंयोग इति** ॥

(उद्द्योतः) अत्यन्त ॥ २८ ॥ ननु काला इत्यस्याभावेऽत्र तल्लाभो न स्यादत आह—**काला इति** ॥ ननु क्तान्तेन समासार्थं तत, अक्तान्तार्थं चेदमपीत्यत आह—**तत्र चेति** ॥

(१२५२ समाधानवार्तिकम् ॥ २ ॥)

॥ * ॥ अनत्यन्तसंयोगार्थं तु ॥ * ॥

(व्याख्याभाष्यम्)

अनत्यन्तसंयोगार्थं तर्हीदं वक्तव्यम् । षण्मुहूर्ताश्चराचराः । ते कदाचिदहर्गच्छन्ति कदाचिद्रात्रिम् । अहर्गताः । रात्रिगताः ॥

(प्रदीपः) **चराचरा इति** । चरन्तीत्यर्थः । **चरिचलिपतिवदीनामच्याक्चाभ्यासस्येति** द्विर्वचनमागमश्च ॥ **कदाचिदहरिति** उत्तरायणे ॥ **कदाचिद्रात्रिमिति** दक्षिणायने । ततश्च षड्भिर्मुहूर्तैरह्नो रात्रेश्च नात्यन्तसं-

योगः। क्रमेण च गच्छन्तः संकलय्य व्यपदिश्यन्ते। अथवैक-देशगमनाद् गच्छन्तीत्युच्यन्ते ॥

(उद्द्योतः) अनत्यन्तसंयोगे क्रान्तार्थं काला इति, अत्यन्त-संयोगेऽक्रान्तार्थमिदमित्युत्तरम्॥ षण्मुहूर्ता इति। तावत्पर्यन्तं हि दिनरात्रवृद्धिह्रासौ देशविशेषे ॥ २८ ॥

(समाधानबाधकभाष्यम्)

नैतदस्ति। गतग्रहणादप्येतत्सिद्धम् ॥

(प्रदीपः) गतग्रहणादिति । द्वितीयाश्रितेत्यत्र निर्दिष्टात् ॥

(समाधानभाष्यम्)

इदं तर्हि—अहरतिसृताः। राज्यतिसृताः। मासप्रमितश्चन्द्रमाः॥ अत्यन्तसंयोगे च ॥ २८ ॥

(प्रदीपः) मासप्रमित इति। आदिकर्मणि कर्तरि क्तः। मासं परिच्छेत्तुमारब्धवानित्यर्थः। प्रतिपच्चन्द्रेण च मासस्यात्यन्तसंयोगाभावः ॥ २८ ॥

(२४० तत्पुरुषसंज्ञासूत्रम् ॥ २। १। २ आ. १९)

३७८ तृतीया तत्कृतार्थेन गुणवचनेन ॥ २।१।२९ ॥

(तत्कृतार्थग्रहणप्रयोजनाधिकरणम्)

(आक्षेपभाष्यम्)

तत्कृतार्थेनेति किमर्थम्?॥

(प्रदीपः) तृतीया त ॥ २९॥ तत्कृतार्थेनेति किमर्थमिति। अयं भावः—दध्ना पटुरित्यत्र यदि दधिकृतं पाटवं विवक्षितं तदा भवितव्यं समासेन विशिष्टद्रव्यसंस्कृतं दध्यपि पाटवं करोतीति तत्कृतत्वसंभवात्। अथ भोजनाद्यपेक्षो दध्नः करणभावो दध्ना भुङ्क्ते पटुरिति तदा सामर्थ्याभावात्समासो न भविष्यति ॥

(उद्द्योतः) तृतीया ॥ २९ ॥ केवलदध्नः पाटवजनकत्वं वैद्यकविरुद्धमत आह—विशिष्टद्रव्येति। शुण्ठिलवणादिरूपेत्यर्थः ॥

(समाधानभाष्यम्)

दध्ना पटुः। घृतेन पटुः ॥

(प्रदीपः) दध्ना पटुरिति। अस्याप्ययं भावः—सर्वत्र क्रियाद्वारकेण संबन्धेन भवितव्यम्। ततश्चेहापि क्रियाद्वारकसंबन्धसंभवात् समासः स्यात् ॥

(उद्द्योतः) सर्वत्र क्रियेति। उत्तरसूत्रे सदृशनिपुणादिग्रहणेन साक्षात्परस्परान्वये एतत्प्रवृत्तिरिति भावः॥ क्रियाद्वारकसम्बन्धेति। भुजिक्रियाद्वारकेत्यर्थः ॥

(समाधानबाधकभाष्यम्)

नैतदस्ति। असामर्थ्यादत्र न भविष्यति॥ कथमसामर्थ्यम्?। सापेक्षमसमर्थं भवतीति। नहि दध्नः पटुना सामर्थ्यम्॥ केन तर्हि?। भुजिना। दध्ना भुङ्क्ते पटुरिति ॥

(प्रदीपः) असामर्थ्यादिति। यत्र साक्षात्सामर्थ्यं नास्ति दध्योदन इत्यादौ तत्र वचनसामर्थ्यात् प्रतीयमानक्रियाद्वारकसंबन्धाश्रयेण समासः। इह तु शष्कुलया खण्ड इत्यादौ साक्षात्सामर्थ्यसंभवे वचनस्य सावकाशत्वाद्दध्ना पटुरित्यत्र न भविष्यति ॥

(उद्द्योतः) यत्रेति। अनेन व्यञ्जनमित्यादिविषये॥ साक्षात्सामर्थ्येति। खडि भेदने इत्यस्मात् घञि निष्पन्नखण्डशब्दार्थक्रियायां करणत्वेनान्वयः॥ सदृशादिग्रहणं च प्रपञ्चार्थमित्यभिमानः॥

(समाधानसाधकभाष्यम्)

इहापि तर्हि न प्राप्नोति—शष्कुलाखण्डः किरिकाण इति। अत्रापि न शष्कुलायाः खण्डेन सामर्थ्यम्॥ केन तर्हि?। करोतिना। शष्कुलया कृतः खण्ड इति ॥

(प्रदीपः) इहापीति। खण्डशब्दस्य गुणोपसर्जनद्रव्यवाचित्वात् साक्षात् संबन्धाभावाच्छष्कुलया अवश्यं क्रियापेक्षितव्या तामन्तरेण कारकत्वायोगात् ॥

(उद्द्योतः) गुणोपसर्जनद्रव्येति। खण्डशब्दो हि तत्र रूढः नतु साध्यावस्थापन्नकारकान्वययोग्यक्रियोपसर्जनद्रव्यवाची तादृशखण्डशब्देन तु कर्तृकरणेकृतेत्येव समासः सिद्ध इति भावः॥ भाष्ये—किरिकाण इति। किरिः सूकरो रोगविशेषो वा ॥

(समाधानबाधकभाष्यम्)

वचनाद्भविष्यति ॥

(प्रदीपः) वचनादिति। करोतिक्रियाकृतसंबन्धाश्रयेणेत्यर्थः ॥

(समाधानसाधकभाष्यम्)

इहापि तर्हि वचनात्प्राप्नोति—दध्ना पटुः घृतेन पटुरिति। तस्मात्तत्कृतार्थग्रहणं कर्तव्यम् ॥

(प्रदीपः) इहापीति। परस्परसंबन्धाय चेत्सर्वत्र क्रिया व्यतिरिक्तापेक्ष्यते, तदात्रापि तदपेक्षसामर्थ्यसद्भावात् समासप्रसङ्ग इत्यर्थः॥ परस्तात्तु तत्कृतार्थग्रहणं निराकरिष्यते ॥

(उद्द्योतः) व्यतिरिक्तेति। पूर्वपदोत्तरपदार्थव्यतिरिक्तेत्यर्थः॥ तदपेक्षेति। भुजिद्वारकेत्यर्थः। कारकतृतीयातिरिक्ततृतीयान्ते तु

नेदं प्रवर्तते उत्तरसूत्रे निपुणादिग्रहणाज्ज्ञापकादिति भावः॥ भाष्ये—तत्कृतार्थग्रहणं कर्तव्यमिति । कृधात्वर्थद्वारके सामर्थ्ये एव यथा स्यान्नतु भुज्यादिद्वारके इत्येतदर्थमित्यर्थः ॥

(गुणवचनग्रहणप्रयोजनाधिकरणम्)

(आक्षेपभाष्यम्)

गुणवचनेनेति किमर्थम्? ॥

(प्रदीपः) **गुणवचनेनेति किमर्थमिति** । अयं भावः—जातेर्नित्यत्वात्तत्कृतत्वाभावाज्जातिवचनेनं समासो न भविष्यति । क्रियावचनेन तु **कर्तृकरणे कृता बहुलमिति** भाव्यं समासेन । 'स्वभावसिद्धं च द्रव्यम्' इति तत्कृतत्वाभावाद् द्रव्यवाचिनापि न भविष्यति ॥

(उद्द्योतः) स्वभावसिद्धमिति । शब्दशक्तिस्वभावेन सिद्धत्वेनैव घटादिपदाद् द्रव्यभानमिति तत्कृतत्वाभाव इति भावः । क्रियत इति पदान्तरसमभिव्याहारेण तु तत्र साध्यत्वप्रतीतिरित्यन्यत् । एवं च दण्डेन घट इत्यादौ दण्डहेतुको घट इत्येव बोधो न तु तत्कृतत्वप्रतीतिरिति तात्पर्यम् ॥

(समाधानभाष्यम्)

गोभिर्वपावान् । धान्येन धनवान् ॥

(प्रदीपः) **गोभिर्वपावानिति** । गोसंबन्धिदध्याद्युपयोगाद्वपावत्त्वमिति तत्कृतत्वमस्ति । वपावच्छब्दस्तु गुणवचनो न भविष्यति । यो हि गुणमुक्त्वा द्रव्यमभिधत्ते यथा शुक्लः पट इति शुक्लशब्दः स गुणवचनः । वपावच्छब्दस्तु सर्वदा वपासंबन्धविशिष्टं द्रव्यमाहेति नासौ गुणवचनः ॥

(उद्द्योतः) भाष्ये—धान्येन धनवानिति । धान्येन हेतुना धनवत्त्वात्तत्कृतत्वमत्रापीति भावः ॥

(आक्षेपभाष्यम्)

किं पुनरिहोदाहरणम्? ॥

(प्रदीपः) **किं पुनरिति** । दध्ना आज्यं घृतेन पाटवमित्यादौ केवलगुणवाचिना समासो नेष्यते । गुणोपसर्जनद्रव्यवचनस्तु द्रव्यवचनत्वाद् गुणवचनो न भविष्यतीति प्रश्नः ॥

(समाधानभाष्यम्)

शङ्कुलाखण्डो देवदत्त इति ॥

(उद्द्योतः) शङ्कुलाखण्डो देवदत्त इति । शङ्कुलाकृतखण्डको देवदत्त इत्यर्थः ॥

(आक्षेपभाष्यम्)

कथं पुनर्गुणवचनेन समास उच्यमानो द्रव्यवचनेन स्यात्? ॥

(समाधानभाष्यम्)

इह "तृतीया तत्कृतार्थेन गुणेन" इतीयता सिद्धम् । सोयमेवं सिद्धे सति यद्वचनग्रहणं करोति तस्यैतत्प्रयोजनम्—एवं यथा विज्ञायेत-'गुणमुक्तवता गुणवचनेन' इति ॥

(प्रदीपः) **गुणेनेति** । अर्थेन च समासासंभवाद् गुणवचनेन भविष्यति । तत्र वचनग्रहणाद् भूतकालपरिग्रहाद् गुणमुक्तवता संप्रति गुणोपसर्जनद्रव्यवाचिना समासो भवतीत्यर्थः ॥

(उद्द्योतः) भूतकालेति । बाहुलकाद्भूते कर्तरि ल्युडिति भावः॥ गुणमुक्तवतेति व्याचष्टे—**संप्रतीति** । तत्त्वं च केवलगुणवाचकत्वेनापि प्रसिद्धस्य यथा शुक्लादेः, पार्थक्येन गुणावाचिनो विशिष्टद्रव्यवचनस्यापि यथा पट्वादेः ॥

(आक्षेपभाष्यम्)

कथं पुनरयं गुणवचनः सन् द्रव्यवचनः संपद्यते? ॥

(प्रदीपः) **कथंपुनरिति** । नित्यत्वाच्छब्दार्थसंबन्धस्योपात्तार्थपरित्यागेनार्थान्तराभिधानं न संभवतीति प्रश्नः ॥

(समाधानभाष्यम्)

आरभ्यते तत्र मतुब्लोपः—*गुणवचनेभ्यो मतुपो लुग्* इति । तद्यथा—शुक्लगुणः शुक्लः, कृष्णगुणः कृष्णः । एवं खण्डगुणः खण्डः ॥

(प्रदीपः) **आरभ्यत इति** । अर्थभेदेन शब्दभेदात् सादृश्यनिबन्धनत्वाच्च प्रत्यभिज्ञायाः । एकत्वे वानेकशक्तियोगात् प्रयोगभेदेनानेकार्थसंबन्ध इति भावः ॥

(उद्द्योतः) भाष्ये—गुणवचनेभ्यो मतुप इति । तत्रापि धर्ममात्रं गुण इति भावः ॥ यद्वेदमर्शआद्यच उपलक्षणम् ॥ नन्वर्थभेदेन शब्दैक्ये मतुपो लोपो व्यर्थोत आह—**अर्थभेदेनेति** ॥ नन्वेवं **गुणमुक्तवतेत्युक्तं** गुणवचनत्वमनुपपन्नमत आह—**सादृश्येति** ॥ **अनेकशक्तीति** । प्रकरणादितश्च तत्तच्छक्त्युद्बोध इति भावः ॥

(लाघवभाष्यम्)

यद्येवं, नार्थस्तत्कृतार्थग्रहणेन । भवति हि शङ्कुलायाः खण्डेन सामर्थ्यम् । असामर्थ्याच्चात्र न भविष्यति दध्ना पटुर्घृतेन पटुरिति । तस्मान्नार्थस्तत्कृतार्थग्रहणेन ॥

(प्रदीपः) **भवति हीति** । अव्यतिरिक्तकल्पान्तरत्वप्रतीयमानसमासार्थान्तर्भूतकरोतिक्रियाद्वारकमिति भावः । दध्ना पटुरित्यत्र तु विपर्ययादसामर्थ्यात्समासाभावः ॥

(उद्द्योतः) भाष्ये—**यद्येवं नार्थस्तत्कृतार्थग्रहणेनेति** । एवं गुणवचनेनेत्यस्यात्र करणे । अयं भावः—तृतीयान्तं गुणवचनेन समस्यत इत्युक्ते गुणस्य जन्यतानियमेन तृतीयान्तार्थस्य तदुत्पत्तिप्रयोजकत्वेन च प्रत्यासत्त्या तृतीयान्तार्थकृतगुणवचनेनैव तृती

यान्तस्य समासो भविष्यतीति दध्ना मुङ्क्ते पटुरक्ष्णा काण इत्यादौ न भविष्यतीति ॥ ननु तृतीयात्र सूत्रे न हेतौ, उत्तरसूत्रे निपुणश्लक्ष्णग्रहणात् । एवं च तृतीयान्तगुणवचनयोः साक्षात्सामर्थ्यासम्भवेन क्रियाद्वारकं तद् ग्राह्यम् । एवं च यतो दध्ना मुङ्क्ते अतः पटुरित्यर्थेके दध्ना पटुरित्यादावपि स्यादत आह—**अव्यतिरिक्तकल्पेति** । गुणवचनतृतीयान्तयोः समभिव्याहारे उक्तरीत्या तत्प्रतीतिरिति भावः ॥ अन्तरङ्गत्वेयमेव हेतुः । अत एव समासार्थान्तर्भूतत्वम् । राजसख इत्यादावन्तर्भूतस्याप्रतीयमानत्वात्**प्रतीयमानेति** ॥

(अर्थपदस्य शब्दपरत्वाधिकरणम्)

(१२५३ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ तृतीयासमासेर्थग्रहणमनर्थकमर्थगतिर्ह्यवचनात् ॥ * ॥

(व्याख्याभाष्यम्)

तृतीयासमासेऽर्थग्रहणमनर्थकम् ॥ किं कारणम् ? । अर्थगतिर्ह्यवचनात् । अन्तरेणापि वचनमर्थगतिर्भविष्यति ॥

(प्रदीपः) **अर्थगतिरिति** । तत्कृतस्यार्थत्वाव्यभिचारादित्यर्थः ॥

(उद्योतः) उक्तन्यायसिद्धमपि तत्कृतार्थग्रहणं स्पष्टप्रतिपत्त्ये अभ्युपगम्य तत्रार्थग्रहणं व्यर्थमाह वार्त्तिककारः—**तृतीयासमास इति** ॥

(१२५४ आक्षेपसाधकवार्तिकम् ॥ २ ॥)

॥ * ॥ निर्देश्यमिति चेत् तृतीयार्थनिर्देशोपि ॥ * ॥

(व्याख्याभाष्यम्)

अथैवमपि निर्देशः कर्तव्य इति चेत् तृतीयार्थनिर्देशोपि कर्तव्यः स्यात्—'तृतीया तदर्थकृतार्थेन' इति वक्तव्यम् ॥

(प्रदीपः) **निर्देश्यमिति चेदिति** । सामर्थ्यलभ्यस्यापि यदि विस्पष्टार्थमुपादानमित्यर्थः ॥

(तटस्थाक्षेपभाष्यम्)

तत्तर्हि वक्तव्यम् ?

(सिद्धान्तिसमाधानभाष्यम्)

न वक्तव्यम् ॥ नायमर्थनिर्देशः ॥ किं तर्हि? । योगाङ्गमिदं निर्दिश्यते । सति च योगाङ्गे योगविभागः करिष्यते—"तृतीया तत्कृतेन गुणवचनेन" समस्यते ॥ ततः—"अर्थेन" अर्थशब्देन च तृतीया समस्यते । धान्यार्थः वसनार्थः हिरण्यार्थः । "पूर्वसदृशसमोनार्थ" इत्यर्थग्रहणं न कर्तव्यं भवतीति ॥ तृतीया ॥ २९ ॥

(प्रदीपः) **योगविभाग इति** । **तत्कृतेति** तृतीयायाश्छान्दसो लुक् । **अर्थेनेति** पृथक्पदमिति वाक्यभेदः संपद्यते ॥ **न कर्तव्यमिति** । अर्थशब्देन समासार्थमिति भावः । **सत्त्वे निविशतेऽपैतीति** लक्षितस्य गुणस्येह ग्रहणम्, कुङ्कुमलोहितादीन्यप्यत्रोदाहरणानीति करोतिक्रिया तत्रावश्यापेक्ष्येति खण्डादीनां संभवदपि धातुवाच्यक्रियारूपत्वं भाष्यकारेण नोक्तम् ॥ २९ ॥

(उद्योतः) **नायमर्थनिर्देश इति** । उभयत्राप्यर्थपरत्वस्य व्याख्यानेनैव सिद्धेरिति भावः ॥ **योगविभाग इति** । योगविभागफलक इत्यर्थः । तदाह—**वाक्यभेदः संपद्यत इति** ॥ भाष्ये—**धान्यार्थ इति** । अन्नाऽर्थ्यत इत्यर्थः प्रयोजनम्, अर्थनमर्थः प्रार्थना वा, करणतृतीयया समास इति हरदत्तादयः । तन्न । **कर्तृकरणे** इत्येव सिद्धत्वात् ॥ तस्माद्धनपर्यायार्थशब्देन सह प्रकृत्यादित्वप्रयुक्ततृतीयान्तस्य समासः । प्रथमार्थे च तृतीया । यद्वा धान्येन कृतोर्थ इति विग्रह इति नव्याः ॥ **अर्थशब्देन समासार्थमिति** । फलान्तरार्थमर्थग्रहणमावश्यकमित्यग्रिमसूत्रे वक्ष्यति कैयटः ॥ **सत्त्वे इत्यादि** । इदं गुणवचनशब्दस्यैव लक्षणमिति गुणपदेन धर्ममात्रं तदुपसर्जनद्रव्यवाचिनायं समास इति बोध्यम् । खण्डस्य तल्लक्षितत्वाभावाच्च ॥ **नोक्तमिति** । रूढ्यर्थस्यैव ततः प्रतीतिरिति भावः ॥ २९ ॥

(२४१ तत्पुरुषसंज्ञासूत्रम् ॥ २ । १ । २ आ. २०)

३७९ पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः ॥ २।१।३० ॥

(प्रदीपः) **पूर्व ॥ ३० ॥** पूर्वसूत्रे अर्थशब्देन समासस्य साधितत्वादिहार्थग्रहणमूनेनाभिसंबध्यमानं तदर्थानां विकलादीनां समासं साधयति । पूर्वसूत्रे त्विहत्यमर्थग्रहणं प्रत्याख्यातम् । अर्थप्रधानत्वान्निर्देशस्योनार्थानामन्तरेणाप्यर्थग्रहणं समासस्य सिद्धत्वात् ॥

(उद्योतः) **पूर्वसदृश ॥ ३० ॥ अर्थग्रहणमूनेनेति** अत एवो**नार्थकलह**मिति स्वरविधायकसूत्रेर्थग्रहणं चरितार्थम् । तत्र हि **लक्षणप्रतिपदोक्त**परिभाषयैतत्सूत्रविहितसमासस्यैव ग्रहणम् । समसदृशयोः पृथगुपादानाच्चानेनैव सम्बन्ध इति बोध्यम् ॥ **अर्थप्रधानत्वान्निर्देशस्येति** । ऊनशब्दोर्थपरः अर्थेन समासासंभवाच्च तद्वाचिनां ग्रहणं तच्चाविशेषात्सर्वेषामिति भावः ॥ केचित्तु माषेण कृतो विकल इत्यर्थे माषविकल इति पूर्वेणैव सिद्धम् । **ऊनार्थेति** सूत्रेऽर्थग्रहणं तु धान्यार्थ इत्यादावन्तोदात्तत्वायेति स्पष्ट-

मेव पूर्व्यादौ । तत्र समासेपि पूर्वसूत्रस्यार्थग्रहणात् सिद्धः । एवं च मापविकलादौ पूर्वपदप्रकृतिस्वरत्वमेवेत्येव भाष्याशयः । अत एव समर्थसूत्रभाष्ये तृतीयातत्कृतेति सूत्रस्योपादानविकल इत्युदाहरणं दत्तमित्याहुः ॥

(न्यूनतापूर्वधिकरणम्)

(१२५५ वार्तिकम् ॥ १ ॥)

॥ * ॥ पूर्वादिष्ववरस्योपसंख्यानम् ॥ * ॥

(व्याख्याभाष्यम्)

पूर्वादिष्ववरस्योपसंख्यानं कर्तव्यम् । आसावरोयं संवत्सरावरोयम् ॥

(उद्द्योतः) अवरस्येति । न च कैयटरीत्योनार्थत्वादेव सिद्धिरिति वाच्यम् । चैत्रादवरः फाल्गुन इत्यादौ पूर्वशब्दसमानार्थताया अपि अवरशब्दस्य दर्शनात् ॥

(सदृशग्रहणप्रत्याख्यानाधिकरणम्)

(सदृशग्रहणप्रत्याख्यानभाष्यम्)

सदृशग्रहण उक्तम् * ॥ किमुक्तम् ? । *सदृशग्रहणमनर्थक तृतीयासमासवचनात्* *षष्ठ्यर्थमिति चेत्तृतीयासमासवचनानर्थक्यम्* इति ॥ पूर्वसदृश ॥ ३० ॥

(प्रदीपः) **सदृशग्रहण उक्तमिति** । वक्ष्यमाणस्यापि बुद्ध्या निरूपितत्वाद्धेतुकालसंप्रेक्षितत्वाद्वा भूतनिर्देशः ॥ **सदृशप्रतिरूपयोः सादृश्य** इत्यत्र वक्ष्यते ॥ पूर्वपदप्रकृतिस्वरविधानार्थं सदृशग्रहणमनर्थकं मात्रा सदृशो मातृसदृश इति। **पूर्वसदृशेति** समासे कृते **तत्पुरुषे तुल्यार्थेति** प्रकृतिस्वरो भविष्यति ॥ अथोच्यते—तुल्यार्थयोगे षष्ठ्यपि पक्षे विधीयते ततश्च मातुः सदृशो मातृसदृश इति यदा षष्ठीसमासः क्रियते, तदा पूर्वपदप्रकृतिस्वरार्थं सदृशग्रहणम् । तथा च दास्याःसदृश इत्याक्रोशे षष्ठ्या अलुकि स्वरः सिध्यति तदा तृतीयासमासे सदृशग्रहणं न कर्तव्यम् । षष्ठीसमासेनैव स्वररूपयोः सिद्धत्वात् ॥ अथोच्यते—हेतुतृतीयार्थमिह सदृशग्रहणं विद्यया सदृशो विद्यासदृश इति । तदपि न संबन्धमात्रविवक्षायां षष्ठीसमासेनैव स्वररूपयोः पूर्वसूत्रेण वा तत्कृतत्वात् सिद्धत्वात् ॥ ३० ॥

(उद्द्योतः) **सदृशग्रहण उक्तमिति** भाष्यकारवचनमित्यभिप्रेत्याह—**हेतुकालसंप्रेक्षितत्वाद्वेति** । हेतुर्वार्तिककारोच्चारणं तस्य यः कालस्तस्य संप्रेक्षितत्वान्मनसि स्थापितत्वादित्यर्थः । कारणकालं कार्ये उपचर्य प्रयोग इति तात्पर्यम् ॥ वार्तिककारवचनमित्यभिप्रेत्य त्वाद्यम् ॥ तदेव युक्तमिति भातिः ॥ **तदा पूर्वपदप्रकृतिस्वरार्थमिति** । अन्यथान्तोदात्तत्वं स्यादित्यर्थः ॥ नन्वत्राभिधानात्षष्ठीसमास एव मास्त्वित्यत आह—**तथा च दास्याइति॥ सिद्धत्वादिति** । न च **मनसः संज्ञायामित्यलुकि** मनसासदृश इति सिद्ध्यर्थमिदमप्यावश्यकमिति वाच्यम् । **तत्कृतत्वेनैव** सिद्धत्वात् अनभिधानेन तत्र समासाभावाच्च । ईदृशसंज्ञायां मानाभावाच्चेति दिक् ॥ **संबन्धमात्रविवक्षायामिति** । अनेन—**'अवश्यं तृतीयासमासो वक्तव्यो यत्र षष्ठ्यर्थो नास्ति भोजनसदृशः' इदमप्यवश्यं वक्तव्यं यत्र षष्ठी श्रूयते दास्याःसदृश इत्याद्यर्थम्'** इति सदृशप्रतिरूपयोरिति सूत्रशेषस्थं भाष्यमेकदेश्युक्तिरिति सूचयति । तत्रापि षष्ठ्यर्थस्य संभवात् । प्रतिपदोक्तपरिभाषया तुल्यार्थैरिति तृतीयान्तेनैव तत्समासप्रवृत्तेश्च ॥ **पूर्वसूत्रेण वेति** । उपादानविकल इतिवदिति भावः ॥ ३० ॥

(२४२ तत्पुरुषसंज्ञासूत्रम् ॥ २ । १ । २ आ. २१)

३८० कर्तृकरणे कृता बहुलम् ॥ २।१।३१ ॥

(अनिष्टवारणाधिकरणम्)

(१२५६ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ कर्तृकरणे कृता केन ॥ * ॥

(व्याख्याभाष्यम्)

कर्तृकरणे कृता केनेति वक्तव्यम्—अहिहतः । नखनिर्भिन्नः । दात्रलूनम् । परशुच्छिन्नम् ॥ कृता केनेति किमर्थम् ? । इह मा भूत् । दात्रेण लूनवान् परशुना छिन्नवान् ॥

(उद्द्योतः) कर्तृकरणे ॥ ३१ ॥ कृताकेनेति । भाष्ये—कृतेति क्तस्योपलक्षकं विशेषणमिति बोध्यम् ॥ कृतेत्यस्य स्थाने क्तेनेति वक्तव्यं कृतेति व्यर्थमिति वार्थः ॥

(आक्षेपभाष्यम्)

तत्तर्हि वक्तव्यम् ? ॥

(समाधानभाष्यम्)

न वक्तव्यम् । बहुलवचनात्सिद्धम् ॥ कर्तृकरणे ॥ ३१ ॥

(प्रदीपः) कर्तृ ॥ ३१ ॥ बहुलवचनादिति । अयं भावः—केनेत्युच्यमाने घनादिभिर्नखनिर्भेद इत्यादौ समासो न प्राप्नोति । तस्माद् बहुलग्रहणमेवाव्याप्त्यतिव्याप्तिपरिहारार्थमाश्रयणीयम् ॥ ३१ ॥

(उद्द्योतः) ननु लाघवात्केनेति युक्तमत आह—अयं भाव इति ॥ ३१ ॥

(२४३ तत्पुरुषसंज्ञासूत्रम् ॥ २।१।२ आ. २२)

३८१ कृत्यैरधिकार्थवचने ॥ २।१।३२ ॥

(प्रदीपः) कृत्यैः ॥ ३२ ॥ स्तुतिनिन्दापरत्वात् क्रियोपादानस्य कर्तृकरणयोर्गौणत्वात् पूर्वेणाप्राप्तः समासोनेन विधीयत इति केचिदाहुः ॥ अन्ये तु प्रपञ्चार्थमेतदित्याहुः । तथा च काकपीता नदीत्यत्राकृत्यैरप्यधिकार्थवचने समासो दृश्यते ॥

(उद्द्योतः) कृत्यै ॥ ३२ ॥ स्तुतिनिन्देति । काकपेयेत्यादौ काककर्तृकपानकर्म नदीति बोधे अल्पाम्भस्त्वपूर्णाम्भस्त्वादिना निन्दास्तुतिमात्रे तात्पर्यात् क्रियाया निष्प्रयोजनत्वेन गौणत्वात्कर्तृकरणयोरपि गौणत्वमिति भावः ॥ केचिदाहुरिति । कर्तृत्वादेस्तृतीयाप्रयोजकत्ववत्समासप्रयोजकत्वस्यापि संभवादित्यरुचिः ॥ तदाह—अन्ये त्विति ॥ ननु कृत्यैरेवाधिकार्थवचन इति नियमार्थं स्यादत आह—काकपीतेति ॥

(इष्टानुपपत्तिपरिहाराधिकरणम्)

(१२५७ वार्तिकम् ॥ १ ॥)

॥ * ॥ कृत्यैरधिकार्थवचनेऽन्यत्रापि दृश्यते ॥ * ॥

(व्याख्याभाष्यम्)

कृत्यैरधिकार्थवचनेऽन्यत्रापि दृश्यतइति वक्तव्यम् । बुसोपेन्ध्यं तृणोपेन्ध्यं घनघात्यम् ॥

(प्रदीपः) कृत्यैरिति । ततश्च नेदं नियमार्थमपि तु प्रपञ्चार्थम् ॥ बुसोपेन्ध्यमिति । अग्नेरल्पत्वात् काष्ठमेतद्बुसेन प्रज्वलनीयमित्यर्थः ॥ घनघात्यमिति । घनेनायःप्रभृतिना घात्यस्य काठिन्यं प्रतिपाद्यते ॥

(उद्द्योतः) नेदं नियमार्थमिति । कृत्यैरधिकार्थवचन एवेत्येवं नियमार्थं नेदमित्यर्थः । भाष्ये—अन्यत्रापि स्तुतिनिन्दाफलकत्वरूपाधिकार्थवचनत्वाभावेपि ॥

(१२५८ वार्तिकम् ॥ २ ॥)

॥ * ॥ साधनं कृतेति वा पादहारकाद्यर्थम् ॥ * ॥

(व्याख्याभाष्यम्)

अथ वा साधनं कृता समस्यत इति वक्तव्यम् ॥ किं प्रयोजनम्? । पादहारकाद्यर्थम् । पादाभ्यां ह्रियते पादहारकः । गले चोप्यते गलेचोपकः ॥ कृत्यैरधि ॥ ३२ ॥

(प्रदीपः) साधनं कृतेति । बहुलग्रहणसहितसूत्रसंदर्भापेक्षो विकल्पः ॥ पादाभ्यामिति । अपादाने पञ्चमी ॥ हारक इति । कृत्यल्युटो बहुलमिति बहुलग्रहणात् कर्मणि ण्वुल् ॥ चोपकइति । चुपेर्ण्यन्तस्य कर्मणि ण्वुल् ॥ ३२ ॥

(उद्द्योतः) सूत्रसंदर्भेति । 'कर्तृकरणे' 'कृत्यैरित्येतत्सूत्रद्वयरूपेत्यर्थः ॥ बहुलग्रहणसहितमिदं वा कर्तव्यं तत्सहितसूत्रसंदर्भो वेतितात्पर्यम् । बहुलग्रहणं त्वत्रापि कर्त्तव्यमेव, परशुना छिन्नवानित्याद्यर्थम् ॥ पादाभ्यामित्यस्य कर्त्तृकरणतृतीयान्तत्वे यथान्यासेपि सिध्यतीत्यत आह—अपादानेपञ्चमीति । पादयोर्ह्रियमाणशरीरापेक्षयावधित्वेनापादानत्वम् । गले चोपक इति । हलदन्तादिति सप्तम्या अलुक् । गले मन्दं प्रायणीय इत्यर्थः ॥ ३२ ॥

(२४४ तत्पुरुषसंज्ञासूत्रम् ॥ २।१।२ आ. २३)

३८२ अन्नेन व्यञ्जनम् ॥ २।१।३३ ॥

(२४५ तत्पुरुषसंज्ञासूत्रम् ॥ २।१।२ आ. २४)

३८३ भक्ष्येण मिश्रीकरणम् ॥२।१।३४॥

(इष्टानुपपत्तिपरिहाराधिकरणम्)

(१२५९ आक्षेपवार्तिकम् ॥१॥)

॥ * ॥ अन्नेन व्यञ्जनं भक्ष्येण मिश्रीकरणमित्यसमर्थसमासः [कारकाणां क्रियासमर्थत्वात्] ॥ * ॥

(व्याख्याभाष्यम्)

"अन्नेन व्यञ्जनम्" "भक्ष्येण मिश्रीकरणम्" इत्यसमर्थसमासोयं द्रष्टव्यः ॥ किं कारणम्? । कारकाणां क्रियासमर्थत्वात् । कारकाणां क्रियया सामर्थ्यमस्ति,न तेषामन्योन्येन । तद्यथा—निश्रयण्या द्वाभ्यां काष्ठाभ्यां सामर्थ्यं न तेषामन्योन्येन ॥

(प्रदीपः) अन्नेन ॥ ३३ ॥ ३४ ॥ तुल्यन्यायत्वाद् युगपत् सूत्रद्वयस्य विचारः ॥ दध्योदन इत्यादौ क्रियावाची शब्दो न प्रयुज्यते, यथा कष्टश्रित इति । क्रियामन्तरेण च द्रव्याणां परस्परसंबन्धो नास्तीत्याह—अन्नेनेति ॥ किंकारणमिति । समासादुपसेकादिक्रियावगमात्तत्कृतमस्त्येव सामर्थ्यमिति प्रश्नः ॥ क्रिययेति । तस्याश्च वाचको नास्तीति तदभावात् सामर्थ्याभावः ॥ निश्रयण्या इति । निश्रयणी-

शब्देन समुदायवृत्तिना उपचारात् सोपानफलकान्यभिधीयन्ते ॥ द्वाभ्यामिति । ऊर्ध्वाभ्यामित्यर्थः ॥

(उद्योतः) असेनव्य ॥ ३३ ॥ ३४ ॥ अनेनापि करणतृतीययैव समासः शाब्दशक्तिस्वभावाद् करणेऽत्यनुवृत्तेर्वा इत्यभिप्रायेणासामर्थ्याशङ्का ॥ द्रव्याणामिति । कारकविभक्त्यन्तवाच्यत्वे इति भावः ॥ फलकानीति । आरोहणावरोहणोपयोगितिर्यक्काष्ठानीत्यर्थः ॥ भाष्ये—निश्रयण्याइति । जातावेकवचनम् ॥

(एकदेशिसमाधानभाष्यम्)

एवं तर्ह्याहायम्—"अन्नेन व्यञ्जनम्" "भक्ष्येण मिश्रीकरणम्" इति । न चास्ति सामर्थ्यम् । तत्र वचनात्समासो भविष्यति ॥

(प्रदीपः) एवमसामर्थ्ये प्रतिपादिते आचार्यदेशीय आह—एवं तर्हीति ॥

(१२६० समाधाननिराकरणवार्तिकम् ॥ २ ॥)

॥ * ॥ वचनप्रामाण्यादिति चेद् नानाकारकाणां प्रतिषेधः ॥ * ॥

(व्याख्याभाष्यम्)

वचनप्रामाण्यादिति चेन्नानाकारकाणां प्रतिषेधो वक्तव्यः । तिष्ठतु दध्ना ओदनो देवदत्तेन भुज्यत इति ॥

(प्रदीपः) नानाकारकाणामिति । भिन्नक्रियापेक्षया कारकाणामित्यर्थः ॥ तिष्ठतु दध्नेति । दध्ना ध्रियतां जीवत्वित्यर्थः । तत्र दध्नः करणत्वम् ॥

(उद्योतः) दध्नेतिसहयोगतृतीयायामुक्तरीत्या करणतृतीयाभावात् समासाप्राप्तेराह—जीवत्विति ॥

(१२६१ न्यासान्तरेणसमाधानवार्तिकम् ॥ ३ ॥)

॥ * ॥ सिद्धं तु समानाधिकरणाधिकारे क्तस्तृतीयापूर्वपद उत्तरपदलोपश्च॥*॥

(व्याख्याभाष्यम्)

सिद्धमेतत् ॥ कथम्? । समानाधिकरणाधिकारे वक्तव्यम्—'क्तान्तस्तृतीयापूर्वपदः समस्यते सुपा, उत्तरपदस्य च लोपो भवति'इति । दध्ना उपसिक्तः दध्युपसिक्तः । दध्युपसिक्तः ओदनो दध्योदनः । गुडेन संसृष्टाः=गुडसंसृष्टाः । गुडसंसृष्टा धानाः=गुडधानाः ॥

(प्रदीपः) एवं सूत्रन्यासं दूषयित्वा वार्तिककार आत्मीयं न्यासं दर्शयति—सिद्धं त्विति ॥

(उद्योतः) सिद्धंत्विति । वार्तिकारम्भेपि दासीभारादित्वात्पूर्वपदप्रकृतिस्वरो बोध्यः । एवंच सूत्रारम्भेण समफलता । तच्च वार्तिकं विशेषणमित्येव सिद्धे समासे पूर्वपदावयवोत्तरपदलोपार्थं कर्तव्यम् ॥

(१२६२ वार्तिकम् ॥ ४ ॥)

॥ * ॥ षष्ठीसमासश्च युक्तपूर्णान्तः ॥ * ॥

(व्याख्याभाष्यम्)

षष्ठीसमासश्च युक्तपूर्णान्तः समस्यते, उत्तरपदस्य च लोपो वक्तव्यः । अश्वानां युक्तोऽश्वयुक्तः अश्वयुक्तो रथोऽश्वरथः । दध्नः पूर्णो दधिपूर्णः दधिपूर्णो घटो दधिघटः ॥

(प्रदीपः) उत्तरपदलोपप्रसङ्गेनान्यदप्याह—षष्ठीसमासश्चेति ॥ अश्वानामिति । संबन्धविवक्षया षष्ठी । तथा दध्न इति ॥

(उद्योतः) संबन्धविवक्षायामिति । कर्तुः करणस्य वा संबन्धत्वेन विवक्षायामित्यर्थः ॥

(प्रत्याक्षेपभाष्यम्)

तत्तर्हीदं बहु वक्तव्यम्? ॥

(१२६३ समाधानवार्तिकम् ॥ ५ ॥)

॥ * ॥ नवाऽसमासेऽदर्शनात् ॥ * ॥

(व्याख्याभाष्यम्)

न वा वक्तव्यम् । किं कारणम्?॥ असमासेऽदर्शनात् । यद्ध्यसमासे दृश्यते समासे च न दृश्यते तद्धि लोपारम्भं प्रयोजयति । न चासमासे उपसिक्तशब्दः संसृष्टशब्दो युक्तशब्दः पूर्णशब्दो वा दृश्यते ॥

(प्रदीपः) असमासेऽदर्शनादिति । असमासो वाक्यं तत्रैव युक्तादयो न दृश्यन्ते । अश्वानां रथोऽश्वरथः दध्नो घटो दधिघट इति युक्तादिशब्दप्रयोगमन्तरेणापि संबन्धप्रतीत्यैव युक्ताद्यर्थानामाक्षेपात् । दधिपूर्णो घट इत्येतत्तु शब्दान्तरमेव तत्समानार्थम्, न तु दधिघट इत्येतस्यैतद्वाक्यम् । अन्यत्र तु प्रत्ययलक्षणार्थो लोपारम्भो यथाऽग्निचिद् दधि पश्येति । इह तु लोपान्वाख्याने प्रयोजनाभावः ॥

(उद्योतः) युक्ताद्यर्थानामाक्षेपादिति । संबन्धत्वेन संबन्धस्यैवात्र भानादिति भावः । तदर्थघटितस्य संबन्धत्वे त्वन्तरङ्गत्वात् तृतीयैव स्यादिति भावः ॥

(वार्तिकावतरणभाष्यम्)

कथं तर्हि सामर्थ्यं गम्यते? ॥

(१२६४ समाधानसाधकवार्तिकम् ॥ ६ ॥)

॥*॥ युक्तार्थसंप्रत्ययाच्च सामर्थ्यम् ॥ * ॥

(व्याख्याभाष्यम्)

दध्ना युक्तार्थता संप्रतीयते ॥

(प्रदीपः) युक्तार्थसंप्रत्ययादिति । युक्तग्रहणं योग्यक्रियोपलक्षणमित्युपसेकादयोपि गृह्यन्ते ॥ एतदुक्तं भवति—दध्योदन इत्युक्ते दध्नः संस्कारकत्वम्, ओदनस्य च संस्कार्यत्वं

प्रतीयते न चोपसेकमन्तरेण संस्कार्यसंस्कारकभावोस्तीति सामर्थ्यादुपसेकप्रतीतिः ॥

(उद्द्योतः) भाष्ये—दध्ना युक्तार्थता संप्रतीयत इति । दध्नेतिपदे सम्बन्धेन युक्तो योर्थ उपसेकक्रियादिरूपस्तदर्थता तस्य प्रतीयत इत्यर्थः । वाक्येपि वाक्यैकदेशन्यायेन दध्नेत्यस्यैव सोर्थ इति बोध्यम् ॥

(वार्तिकावतरणभाष्यम्)

कथं पुनर्ज्ञायते—दध्ना युक्तार्थता संप्रतीयत इति ? ॥

(१२६५ समाधानसाधकवार्तिकम् ॥ ७ ॥)

॥ * ॥ संप्रत्ययाच्च तदर्थाध्यवसानम् [संप्रतीयमानार्थलोपे ह्यनवस्था ॥*॥]

(व्याख्याभाष्यम्)

संप्रत्ययाच्च तदर्थोध्यवसीयते ॥ अवश्यं चैतदेवं विज्ञेयम् । संप्रतीयमानार्थलोपे ह्यनवस्था ॥ यो हि मन्यते संप्रतीयमानार्थानां शब्दानां लोपो भवतीति । अनवस्था तस्य लोपस्य स्यात् । दधीत्युक्ते बहवोर्था गम्यन्ते मन्दकमुत्तरकं निलीनकमिति । तद्वाचिनां शब्दानां लोपो वक्तव्यः स्यात् । तथा गुड इत्युक्ते मधुरशब्दस्य, शृङ्गवेरमिति च कटुकशब्दस्य । अन्तरेणापि खलु शब्दप्रयोगं बहवोऽर्था गम्यन्तेक्षिनिकोचैः पाणिविहारैश्च । तद्वाचिनां शब्दानां लोपो वक्तव्यः स्यात् ॥ अश्वेन ॥ ३३ ॥ भक्ष्येण ॥ ३४ ॥

(प्रदीपः) संप्रत्ययाच्चेति । सर्वलोकव्यवहारप्रसिद्धत्वादिति भावः । अत एव न प्रतिज्ञातार्थैकदेशो हेतुः ॥ तदर्थाध्यवसानमिति । संदेहरहितस्तदर्थनिश्चय इत्यर्थः ॥ मन्दकमिति । मन्दजातम् ॥ उत्तरकमिति । परिपक्वावस्थोपरि घनभावः ॥ निलीनकमिति । पक्वावस्थायां भ्रष्टम् । एषां विशेषाणां संभवाद्दधीत्युक्ते संप्रत्ययः ॥ अक्षिनिकोचैरिति । प्रकारान्तरेण विधिनिषेधलक्षणार्थावसायाचरितार्थत्वाद् यथा शब्दानां प्रयोगो नास्ति तथा युक्तादीनामपीत्यर्थः ॥ ३३ ॥ ३४ ॥

(उद्द्योतः) नन्वध्यवसानं संप्रत्यय इति पर्यायस्तथा च हेतुसाध्ययोरविशेष इत्यत आह—सर्वलोकव्यवहारेति । अर्थविशिष्टं ज्ञानं प्रतिज्ञातोर्थः, तदेकदेशो ज्ञानं हेतुरित्यर्थः ॥ निश्चय इत्यस्यैव विवरणं संदेहरहित इति ॥ दधीत्युक्तेसंप्रत्यय इति । अयं च प्रत्यय आनुमानिको वाक्यैकदेशन्यायेन वा ॥ प्रकारान्तरेणेति । चेष्टयेत्यर्थः ॥ चरितार्थत्वादिति । शब्दप्रयोगकार्यस्य बोधस्य प्रकारान्तरेण संपन्नत्वादिति भावः ॥ ३३ ॥ ३४ ॥

(२४६ तत्पुरुषसंज्ञासूत्रम् ॥ २।१।२ आ. २५)

३८४ चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः ॥२।१।३५ ॥

(प्रदीपः) चतुर्थी ॥ ३५ ॥ चतुर्थीचाशिषीति हितयोगे या चतुर्थी तदन्तस्य समासो न भवति । समासादाशिषोऽनवगमादिति केचिदाहुः ॥

(उद्द्योतः) चतुर्थीतद ॥ ३५ ॥ समासादाशिषोऽनवगमादिति । एवं चानभिधानात्समासो नेति भावः ॥ वस्तु—आशिषि आशीर्विषयस्य विधेयत्वं तदाश्रयस्योद्देश्यत्वं च प्रतीयते । न च वृत्तावुद्देश्यविधेयभावेनान्वयो व्युत्पत्तिसिद्ध इति ॥ तत्र समासतोपि अभ्यासलोप इत्यादावुद्देश्यत्वादिप्रतीतेः ॥ वस्तुतस्तु आशीर्विषयक्रियान्वय्यर्थकात्प्रातिपदिकात्तद्द्वारके आयुष्यादियोगे चतुर्थीति तदर्थात् उभयोरपि क्रियान्वयेन परस्परमसामर्थ्यात्समासस्तेन न । एवं चैतज्ज्ञापकसिद्धैव हितयोगे चतुर्थीति तात्पर्यम् ॥

(पाणिनीयन्यासेदूषणाधिकरणम्)

(आक्षेपभाष्यम्)

किं चतुर्थ्यन्तस्य तदर्थमात्रेण समासो भवति?॥

(प्रदीपः) पाणिनीये लक्षणेऽतिव्याप्तिं पुनर्र्कि च वा पूर्वाचार्यन्यासे त्वव्याप्तिं मत्वा विचारः क्रियते—किं चतुर्थ्यन्तस्येति । विशेषानुपादानाद्दोषदर्शनाच्च प्रश्नः ॥

(उद्द्योतः) अतिव्याप्तिः । रन्धनाय स्थालीत्यादौ ॥ पुनरुक्तिः । बलिरक्षितग्रहणस्य ॥ अव्याप्तिः । अश्वघासे ॥

(दृष्टापत्तिभाष्यम्)

एवं भवितुमर्हति ॥

(प्रदीपः) इतरः स्ववचनेनैव दोषमभिधापयितुमाह—एवं भवितुमर्हतीति ॥

(उद्द्योतः) स्ववचनेनैवेति । स्वशब्देनात्र पूर्वपक्षी । सर्वनाम्नां बुद्धिस्थपरामर्शकत्वादिति भावः ॥ तद्वचनेनैवेति युक्तः पाठः ॥

(१२६६ दूषणवार्तिकम् ॥ १ ॥)

॥ * ॥ चतुर्थी तदर्थमात्रेण चेत्सर्वप्रसङ्गोविशेषात् ॥ * ॥

(व्याख्याभाष्यम्)

चतुर्थी तदर्थमात्रेण चेत्सर्वप्रसङ्गः सर्वस्य चतु-

र्थ्यन्तस्य तदर्थमात्रेण सह समासः प्राप्नोति । अनेनापि प्राप्नोति—रन्धनाय स्थाली अवहननायोलूखलमिति ॥ किं कारणम्? । अविशेषात् । नहि कश्चिद्विशेष उपादीयते—एवंजातीयकस्य चतुर्थ्यन्तस्य तदर्थेन सह समासो भवतीति । अनुपादीयमानविशेषे सर्वप्रसङ्गः ॥

(प्रदीपः) सर्वप्रसङ्ग इति । असत्यपि प्रकृतिविकारभाव इत्यर्थः ॥

(१२६७ दूषणवार्तिकम् ॥ २ ॥)

॥ * ॥ बलिरक्षिताभ्यां चानर्थकं वचनम् ॥ * ॥

(व्याख्याभाष्यम्)

बलिरक्षिताभ्यां च समासवचनमनर्थकम् । योहि महाराजाय बलिः स महाराजार्थो भवति । तत्र तदर्थ इत्येव सिद्धम् ॥

(प्रदीपः) यो हीति । देयस्य बलेः संप्रदानार्थतास्तीति तादर्थ्याश्रयः समासः सिद्धः ॥

(पूर्वाचार्यन्यासेदूषणाधिकरणम्)

(पूर्वाचार्यन्यासभाष्यम्)

यदि पुनर् "विकृतिश्चतुर्थ्यन्ता प्रकृत्या सह समस्यते"इत्येतल्लक्षणं क्रियेत ॥

(प्रदीपः) इदानीं पूर्वाचार्यसूत्रं विचार्यते—यदि पुनरिति ॥

(१२६८ दूषणवार्तिकम् ॥ ३ ॥)

॥ * ॥ विकृतिः प्रकृत्येति चेदश्वघासादीनामुपसंख्यानम् ॥ * ॥

(व्याख्याभाष्यम्)

"विकृतिः प्रकृत्या"इति चेदश्वघासादीनामुपसंख्यानं कर्तव्यम् । अश्वघासः श्वश्रूसुरं हस्तिविधेति ॥

(प्रदीपः) अश्वघास इति । तादर्थ्यमत्रास्ति न तु प्रकृतिविकारभावः ॥ श्वश्रूसुरमिति । विभाषासेनासुरेति नपुंसकत्वम् ॥ हस्तिविधेति । विधा हस्त्यन्नं माषादि ॥

(१२६९ वार्तिकम् ॥ ४ ॥)

॥ * ॥ अर्थेन नित्यसमासवचनम् ॥ * ॥

(व्याख्याभाष्यम्)

अर्थशब्देन नित्यं समासो वक्तव्यः । ब्राह्मणार्थं क्षत्रियार्थम् ॥

(प्रदीपः) अर्थेनेति । महाविभाषाधिकाराद् विकल्पनिवृत्त्यर्थं वचनम् ॥

(आक्षेपभाष्यम्)

किं विकृतिश्चतुर्थ्यन्ता प्रकृत्या सह समस्यत इत्यतोऽर्थेन नित्यसमासो वक्तव्यः ? ॥

(प्रदीपः) किं विकृतिरिति । तदनन्तरमभिधानात्तस्यैव लक्षणस्य दोषान्तरं मन्यते ॥

(समाधानभाष्यम्)

नेत्याह । सर्वथाऽर्थेन नित्यसमासो वक्तव्यः विग्रहो मा भूदिति ॥

(प्रदीपः) नेत्याहेति । आनन्तर्ये सामर्थ्याभावे सत्यकारणमित्यर्थः ॥

(उद्द्योतः) आनन्तर्यमिति । सर्वन्यासेषु वचनारम्भस्यावश्यकत्वरूपसामर्थ्ये सति तत्र कारणमित्यर्थः ॥ सामर्थ्याभावे इति क्वचित्पाठः । तदा न्यासान्तरेऽकर्तव्यतायोग्यत्वाभावे इत्यर्थो बोध्यः ॥

(१२७० द्वितीयखण्डवार्तिकम् ॥ ५ ॥)

॥ * ॥ सर्वलिङ्गता च ॥ * ॥

(व्याख्याभाष्यम्)

सर्वलिङ्गता च वक्तव्या । ब्राह्मणार्थं पयः ब्राह्मणार्थः सूपः ब्राह्मणार्था यवागूरिति ॥

(प्रदीपः) सर्वलिङ्गता चेति । परवल्लिङ्गमिति पुंस्त्वमेव प्राप्नोति ॥ अभिधेयवशेन च सर्वलिङ्गता विज्ञेयेति दर्शयति—ब्राह्मणार्थमिति ॥

(उद्द्योतः) परवल्लिङ्गमिति पुंस्त्वमिति । परस्योत्तरपदार्थस्य प्रधानत्वात्तद्देव लिङ्गं समासेपि प्राप्नोतीत्यर्थः । ननु सूत्रस्यात्र विषय इति बोध्यं, तस्य पूर्वपदार्थप्रधानैकदेशिसमासविषयकत्वात् ॥ तद्वक्ष्यति भगवान् अर्थशब्दोयं पुल्लिङ्ग इत्यादि ॥ अभिधेयवशेनेति । समुदायार्थनिरूपितविशेष्यतावदर्थवशेनेत्यर्थः ॥

(आक्षेपभाष्यम्)

किमर्थेन नित्यसमास उच्यते इत्यतः सर्वलिङ्गता वक्तव्या ? ॥

(प्रदीपः) किमर्थेनेति । पूर्ववत् प्रश्नप्रतिवचने ॥

(समाधानभाष्यम्)

नेत्याह । सर्वथा सर्वलिङ्गता वक्तव्या । किं

कारणम्? । अर्थशब्दोयं पुल्लिङ्गः, उत्तरपदार्थप्रधानश्च सत्पुरुषः, तेन पुल्लिङ्गस्यैव समासस्याभिधानं स्यात् स्त्रीनपुंसकलिङ्गस्य न स्यात् ॥

(उद्योतः) भाष्ये—समासस्याभिधानमिति । समासार्थस्येत्यर्थः ॥

(आक्षेपभाष्यम्)

तत्तर्हीदं बहु वक्तव्यम् । *विकृतिः प्रकृत्येति वक्तव्यम्* । *अश्वघासादीनामुपसंख्यानं कर्तव्यम्* । *अर्थेन नित्यसमासो वक्तव्यः सर्वलिङ्गता च वक्तव्या* ॥

(प्रदीपः) इदानीं भाष्यकारः पाणिनीयं सूत्रं समर्थयितुंचोदकमुखेनाह—तत्तर्हीति ॥

(समाधानभाष्यम्)

न वक्तव्यम् । यत्तावदुच्यते—"विकृतिः प्रकृत्येति वक्तव्यम्" इति । न वक्तव्यम् । आचार्यप्रवृत्तिर्ज्ञापयति—'विकृतिश्चतुर्थ्यन्ता प्रकृत्या सह समस्यते' इति । यदयं बलिरक्षितग्रहणं करोति ॥ कथं कृत्वा ज्ञापकम्? । यथाजातीयकानां समासे बलिरक्षितग्रहणेनार्थः तथाजातीयकानां समासः । यदि च विकृतिश्चतुर्थ्यन्ता प्रकृत्या सह समस्यते न तदर्थमात्रेण । ततो बलिरक्षितग्रहणमर्थवद्भवति ॥

(प्रदीपः) यदयमिति । यदि तदर्थमात्रेण चतुर्थीसमासः स्यात् तदा बलिरक्षितग्रहणं न कुर्यात्तादर्थ्यस्य संभवात्तदर्थग्रहणेनैव समासस्य सिद्धत्वात् ॥

(द्वितीयवार्तिकप्रत्याख्यानभाष्यम्)

यदप्युच्यते—"अश्वघासादीनामुपसंख्यानं कर्तव्यम्" इति ॥ न कर्तव्यम् । अश्वघासादयः षष्ठीसमासा भविष्यन्ति । यद्धि यदर्थं भवति अयमपि तत्राभिसंबन्धो भवति—'अस्येदम्' इति । तद्यथा—गुरोरिदं—गुर्वर्थमिति ॥

(प्रदीपः) अयमपीति । तादर्थ्ये संबन्धविशेषः । विशेषे च सामान्यं संभवतीति तन्मात्रविवक्षायां षष्ठी प्रवर्तत एवेति भावः । अथवाश्वानां घास इति योग्यतामात्रं विवक्ष्यते न तु तादर्थ्यम् ॥

(उद्योतः) तन्मात्रेति । संबन्धत्वमात्रेत्यर्थः । इदमेव युक्तं, गुरोरिदं गुर्वर्थमित्यत्रास्यैव प्रकारस्य संभवात् । भाष्ये—गुरोरिदं गुर्वर्थमिति । षष्ठीसमासोप्येतद्विषये नित्य एव भाष्यप्रामाण्यादिति बोध्यम् ॥

(आक्षेपभाष्यम्)

ननु च स्वरे भेदो भवति—चतुर्थीसमासे सति पूर्वपदप्रकृतिस्वरत्वेन भवितव्यम् । षष्ठीसमासे सति पुनरन्तोदात्तत्वेन ॥

(समाधानभाष्यम्)

नास्ति भेदः । चतुर्थीसमासेपि सत्यन्तोदात्तत्वेनैव भवितव्यम् । कथम्? । आचार्यप्रवृत्तिर्ज्ञापयति—'विकृतिश्चतुर्थ्यन्ता प्रकृतिस्वरा भवति, न चतुर्थीमात्रम्' इति । यदयं "चतुर्थी तदर्थे" "अर्थे" "क्ते च" इत्यर्थग्रहणं क्तग्रहणं च करोति ॥ कथं कृत्वा ज्ञापकम्? । यथाजातीयकानां प्रकृतिस्वरत्वेऽर्थग्रहणेन क्तग्रहणेन चार्थः, तथाजातीयकानां प्रकृतिस्वरत्वम् । यदि च विकृतिश्चतुर्थ्यन्ता प्रकृत्या भवति न चतुर्थीमात्रम्, ततोर्थग्रहणं क्तग्रहणं चार्थवद्भवति ॥

(प्रदीपः) रन्धनस्थाल्यादयस्त्वनभिधानात् षष्ठीसमासा न भवन्ति । यूपदार्वादिषु चतुर्थी तदर्थइति स्वरसिद्ध्यर्थं तादर्थ्यमेव संबन्धविशेषो विवक्ष्यते, न संबन्धसामान्यमिति षष्ठीसमासाभावः ॥

(उद्योतः) भाष्ये—अर्थे क्ते चेति । न च क्तग्रहणं हितार्थं तत्रातादर्थ्येपि हितयोगे चेति चतुर्थीविधानादिति वाच्यम् । ज्ञापकपरभाष्यप्रामाण्येनात्रापि तदर्थ इत्यस्य संबन्धेनादोषात् । न चरक्षितार्थम् । तत्र तादर्थ्ये चतुर्थ्या एव सत्त्वात् । वृत्त्युक्तसंप्रदानचतुर्थी तु न । तत्त्वस्योपपादयितुमशक्यत्वात् । भाष्यप्रामाण्येनानभिधानात्संप्रदानत्वाभावकल्पनाच्च ॥ रंधनस्थाल्यादयस्त्वनभिधानादिति । अत एवोपक्रमस्थं भाष्यं संगच्छते ॥ ननु यूपदार्वादावपि अश्वघासादिवत् संबन्धसामान्यविवक्षायां षष्ठीसमासेन्तोदात्तत्वमपि स्यादत आह—यूपदार्वादिष्विति ॥ तादर्थ्यमेवेति । तादर्थ्यरूपः संबन्धविशेष एवेत्यर्थः ॥ नन्वेवमश्वघासादौ चतुर्थीसमास एवास्तु, बलिरक्षितग्रहणं तज्ज्ञापितं प्रकृतिविकृतिग्रहणं च मास्तु, पूर्वपदप्रकृतिस्वरत्वं तु भाष्योक्तरीत्यैव न भविष्यति, रन्धनाय स्थालीत्यादौ षष्ठीसमासवदयमपि अनभिधानान्न भविष्यतीति चेत् ॥ न, रन्धनाय स्थालीत्यादौ षष्ठ्येव न, तादर्थ्यत्वेनैव तत्र संबन्धस्य प्रतीतेः । एवं च तत्र चतुर्थीसमासवारणार्थं तस्यावश्यकत्वादिति भाष्याशयात् । कैयटेऽनभिधानादित्यस्य षष्ठ्यनभिधानादित्येवार्थः ॥

(तृतीयवार्तिकप्रत्याख्यानभाष्यम्)

यदप्युच्यते—"अर्थेन नित्यसमासो वक्तव्यः" इति । न वक्तव्यः । सर्थप् प्रत्ययः करिष्यते ॥ किं कृतं भवति? ॥ न चैव हि कदाचित्प्रत्ययेन विग्रहो भवति । अपि च सर्वलिङ्गता सिद्धा भवति ॥

(प्रदीपः) सर्थबिति । तदर्थं विकृतेरित्यत्र तदर्थे सर्थबिति क्रियते । तादर्थ्येन चतुर्थी विभक्तिराक्षिप्यते । तस्मैहितमित्यतो वानुवर्तते । तेन चतुर्थ्यन्तात् तादर्थ्येभि-

धेये सर्थप्प्रत्ययो भवति । सकारः पदत्वाय । तेन राजार्थे भवदर्थमित्यादौ न लोपादीनि भवन्ति । पकारोऽनुदात्तार्थः । तेन प्रकृतेर्यथाप्राप्तः स्वरो भवतीति अर्थ इति स्वरार्थं सूत्रं न कर्तव्यं भवति ॥ न चैवेति । प्रत्यये कृते तद्धितान्तत्वात् प्रातिपदिकत्वात् सुब्लुका भवितव्यमिति विग्रहाभावः ॥

(आक्षेपभाष्यम्)

यदि सर्थप् प्रत्ययः क्रियते, इत्संज्ञा न प्राप्नोति॥ अथापि कथंचिदित्संज्ञा स्यात्, एवमपि श्र्यर्थं इवर्थम् "अङ्गस्य" इतीयङुवङौ स्याताम् ॥

(प्रदीपः) **अथापीति।** आदिर्ञिटुडवष्षः प्रत्ययस्येति संहितया सूत्रपाठे सकारस्यापि कृतष्टुत्वस्य निर्देशादिति भावः ॥

(उद्द्योतः) भाष्ये—इत्संज्ञा न प्राप्नोतीति । आद्यसकारस्येत्यर्थः ॥

(समाधानभाष्यम्)

एवं तर्हि बहुव्रीहिर्भविष्यति ॥ किं कृतं भवति? । भवति वै कश्चिदस्वपदविग्रहो बहुव्रीहिः । तद्यथा—शोभनं मुखमस्याः सुमुखीति ॥

(प्रदीपः) **शोभनमिति ।** सुशब्दपर्यायेण शोभनशब्देन विग्रहः सुशब्दस्य त्वसत्त्ववाचित्वात् तेन नास्ति विग्रहः। अत्र च ब्राह्मणायार्थोऽस्येति विग्रहो न भवतीति विवक्षितम् । ब्राह्मणोऽर्थोऽस्येत्येवं समानाधिकरणस्तु विग्रहो भवत्येव । अत्र चार्थशब्दः प्रयोजनवाची ॥

(उद्द्योतः) **भवति वै कश्चिदिति ।** एवं च वैकल्पिकेपि बहुव्रीहौ यथान्यत्रापि क्वचिदस्वपदत्वम् । एवमत्रापि ब्राह्मणोऽर्थः प्रयोजनमुपकार्यत्वेन यस्येति प्रयोजनवाच्यर्थशब्देन विग्रहः, नतु चतुर्थ्यन्तेन विग्रहः ब्राह्मणायार्थमुपकारोऽस्येतीति भावः ॥ तद् ध्वनयन्नाह—अत्र चेति ॥ **प्रयोजनवाचीति ।** उपकार्यत्वेन हि ब्राह्मणस्य प्रयोजनता॥ **प्रयोजकवाचीति** पाठे यद्ब्राह्मणार्थं पयस्तस्य ब्राह्मणः प्रयोजको भवतीति भावः ॥

(आक्षेपभाष्यम्)

नैवं शक्यम् । इह हि महदर्थमित्यात्वकपौ प्रसज्येयाताम् ॥

(समाधानभाष्यम्)

एवं तर्हि तदर्थस्योत्तरपदस्यार्थशब्द आदेशः करिष्यते ॥ किं कृतं भवति? । न चैव हि कदाचिदादेशेन विग्रहो भवति । अपि च सर्वलिङ्गता सिद्धा भवति ॥

(प्रदीपः) **एवं तर्हीति ।** ब्राह्मणाय पय इति समासे कृते पयःशब्दस्य स्थाने अर्थशब्द आदेशः क्रियते । तेन ब्राह्मणपय इति तादर्थ्ये प्रयोगो न भवति । चतुर्थ्याश्च समासे निवृत्तत्वादादेशेनार्थशब्देन विग्रहाभावः । अर्थविशेषाभिव्यक्तये च पयःशब्दस्य प्रयोगः ॥

(आक्षेपभाष्यम्)

तत्तर्हि वक्तव्यम्? ॥

(समाधानभाष्यम्)

न वक्तव्यम् । योगविभागः करिष्यते—"चतुर्थी" सुबन्तेन सह समस्यते ॥ ततः—"तदर्थार्थ" तदर्थस्य चोत्तरपदस्यार्थशब्द आदेशो भवति ॥

(आक्षेपभाष्यम्)

इहापि तर्हि समासः प्राप्नोति—छात्राय रुचितं छात्राय स्वदितमिति ॥

(प्रदीपः) **इहापीति ।** यदि चतुर्थीत्येतावल्लक्षणं क्रियेत इत्यर्थः ॥

(समाधानभाष्यम्)

आचार्यप्रवृत्तिर्ज्ञापयति—'तादर्थ्ये या चतुर्थी सा समस्यते, न चतुर्थीमात्रम्' इति । यदयं हितसुखग्रहणं करोति ॥ कथं कृत्वा ज्ञापकम्? । यथाजातीयकानां समासे हितसुखग्रहणेनार्थस्तथाजातीयकानां समासः ॥ यदि च तादर्थ्ये या चतुर्थी सा समस्यते, न चतुर्थीमात्रम्; ततो हितसुखग्रहणमर्थवद्भवति ॥

(उद्द्योतः) भाष्ये—**यदयं हितेति । हितयोगे चेति** वार्तिकात्तद्योगे चतुर्थीति भावः । न च सुखग्रहणस्य न ज्ञापकत्वं तद्योगे चतुर्थ्यभावात् इति वाच्यम् । **हितयोगे चेति** चेन सुखयोगेपि सेति भाष्याशयात् ॥

(आक्षेपभाष्यम्)

इहापि तदर्थस्योत्तरपदस्यार्थशब्द आदेशः प्राप्नोति—यूपाय दारु यूपदारु ॥

(समाधानभाष्यम्)

वा च विधास्यते ॥

(प्रदीपः) **वाचेति ।** महाविभाषयार्थादेशो विकल्प्यते । तेन यूपार्थं दारु, यूपदार्विति द्वैरूप्यं भवति ॥

(आक्षेपभाष्यम्)

इहापि तर्हि विभाषा प्राप्नोति—ब्राह्मणार्थं क्षत्रियार्थमिति ॥

(समाधानभाष्यम्)

एवं तर्ह्याचार्यप्रवृत्तिर्ज्ञापयति—'प्रकृतिविकृत्योर्यः समासः तत्र तदर्थस्योत्तरपदस्य वाऽर्थ-

शब्द आदेशो भवति अन्यत्र नित्यः, इति । यदयं बलिरक्षितग्रहणं करोति ॥

(प्रदीपः) यदयमिति । कुबेरार्थो बलिः कुबेरबलिरिति रूपद्वये सिद्धे बलिरक्षितग्रहणं ज्ञापकं प्रकृतिविकारभावादन्यत्र नित्योऽर्थादेशः तदर्थस्य भवतीति ॥

(आक्षेपभाष्यम्)

एवं तर्हि—'उदकार्थो वीवधः' स्थानिवद्भावादुदभावः प्राप्नोति। तस्मान्नैवं शक्यम्। न चेदेवम्, *अर्थेन नित्यसमासो वक्तव्यः**सर्वलिङ्गता च*॥

(प्रदीपः) उदकार्थ इति । यदि वीवधशब्दस्यार्थादेशः क्रियते तदा तस्य स्थानिवद्भावान्मन्थौदनेति पक्षे उदकशब्दस्योदादेशः प्राप्नोति ॥

(समाधानभाष्यम्)

नैष दोषः। इदं तावदयं प्रष्टव्यः—अथेह 'ब्राह्मणेभ्यः' इति कैषा चतुर्थी?॥ तादर्थ्ये इत्याह॥ यदि तादर्थ्ये चतुर्थी, अर्थशब्दस्य प्रयोगेण न भवितव्यम्—उक्तार्थानामप्रयोग इति ॥

(उद्द्योतः) भाष्ये—उक्तार्थानामिति । न च तादर्थ्यस्य चतुर्थ्योक्तत्वेप्याश्रयबोधकार्थशब्दस्य कथमुक्तार्थकत्वमिति वाच्यम्। सम्बन्धेन द्वितीयसम्बन्ध्याऽऽक्षेपेणैव तल्लाभस्याप्युपपत्तेः ॥

(आक्षेपभाष्यम्)

समासोपि तर्हि न प्राप्नोति ॥

(प्रदीपः) समासोपीति । चतुर्थ्यन्तस्यार्थशब्देन समासो विधीयते न चैतयोर्यौगपद्येन भाव इति भावः ॥

(समाधानभाष्यम्)

वचनात्समासो भविष्यति ॥

(प्रदीपः) वचनादिति । असत्यपि लौकिके युगपत्प्रयोगे प्रक्रियायां यौगपद्यमस्त्येवेत्यर्थः ॥

(उद्द्योतः) वचनादिति । चतुर्थीतदर्थार्थेति वचनात् ॥

(चतुर्थवार्तिकप्रत्याख्यानभाष्यम्)

यदप्युच्यते—'*सर्वलिङ्गता वक्तव्या*' इति॥ न वक्तव्या । लिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्य ॥ चतुर्थी ॥ ३५ ॥

(प्रदीपः) लिङ्गमिति । ततश्च परवल्लिङ्गमित्यस्य लक्षणस्याभावाल्लौकिकप्रयोगाश्रयात् सर्वलिङ्गता भविष्यतीत्यर्थः ॥ ३५ ॥

(उद्द्योतः) लक्षणस्याभावादिति । परस्योत्तरपदस्य प्रधानत्वात्प्रधानवल्लिङ्गं समासस्येति लक्षणस्याभावादित्यर्थः ॥ यद्वा—एकदेशिसमासविषयकतया तस्यात्राभावात्प्रत्याख्यासमानत्वादित्यर्थः ॥ ३५ ॥

(२४७ तत्पुरुषसंज्ञासूत्रम् ॥ २।१।२। आ. २६)

३८५ पञ्चमी भयेन ॥२।१।३६॥

(न्यूनतापरिहाराधिकरणम्)

(वार्तिकावतरणभाष्यम्)

अत्यल्पमिदमुच्यते—'भयेन' इति ॥

(१२७१ वार्तिकम् ॥ १ ॥)

[॥ * ॥ भयभीतभीतिभीभिः ॥ * ॥]

(भाष्यम्) भयभीतभीतिभीभिरिति वक्तव्यम्॥ वृकाद्भयं वृकभयम् ॥ वृकाद्भीतः वृकभीतः। वृकाद्भीतिः वृकभीतिः । वृकाद्भीः वृकभीरिति ॥

(प्रदीपः) पञ्चमी ॥ ३६ ॥ भयेनेति स्वरूपग्रहणादव्याप्तिं मत्वा वार्तिकारम्भः । व्याख्यानादर्थग्रहणे वृकेभ्यस्त्रास इत्यादावपि प्रसङ्गः ॥

(भाष्यम्) अपर आह—

(१२७२ वार्तिकन्यासान्तरम् ॥ २ ॥)

[॥ * ॥ भयनिर्गतजुगुप्सुभिः ॥ * ॥]

(भाष्यम्) भयनिर्गतजुगुप्सुभिरिति वक्तव्यम्। वृकभयं ग्रामनिर्गतः अधर्मजुगुप्सुः ॥ पञ्चमी भयेन ॥ ३६ ॥

(२४८ तत्पुरुषसंज्ञासूत्रम् ॥ २।१।२७ ॥)

३८८ सप्तमी शौण्डैः ॥ २ । १ । ३९ ॥

(न्यूनताशङ्कापरिहाराधिकरणम्)

(१२७२ वार्तिकम् ॥ १ ॥)

[॥ * ॥ शौण्डादिभिः ॥ * ॥]

(व्याख्याभाष्यम्)

शौण्डादिभिरिति वक्तव्यम्। इहापि यथा स्यात् अक्षधूर्तः स्त्रीधूर्तः अक्षकितवः स्त्रीकितव इति ॥

(प्रदीपः) सप्तमी ॥ ३९ ॥ शौण्डादिभिरिति वक्तव्यमिति । बहुवचनमर्थग्रहणे सति पर्यायार्थं वा स्याद् बहुवचनान्तसमासविधानार्थं वा । गणपाठस्तु सप्तम्यसंग्रहीतत्वादकिंचित्करः स्यादिति भावः ॥

(उद्द्योतः) सप्तमी ॥ ३९ ॥ अर्थग्रहणेसतीति । अर्थग्रहणद्वारा पर्यायार्थं स्यादित्यर्थः ॥

(आक्षेपभाष्यम्)

तत्तर्हि वक्तव्यम्?॥

(समाधानभाष्यम्)

न वक्तव्यम्। बहुवचननिर्देशाच्छौण्डादिभिरिति विज्ञास्यते॥ सप्तमी शौण्डैः॥ ३९॥

(प्रदीपः) बहुवचननिर्देशादिति। धूर्तादीनां साहचर्यादारोपितशौण्डशब्दरूपाणां शौण्डशब्दस्य च शौण्डशब्देनाभिधानाद् यथा छत्रिणो गच्छन्तीति भावः। वृत्त्यन्तर्भूतप्रसक्त्यादिक्रियापेक्षोक्षादीनामाधारभावः॥ अन्तःशब्दोत्र पठ्यते तद्योगे अवयविन आधारत्वविवक्षायां सप्तमी॥३९॥

(उद्द्योतः) भाष्ये—बहुवचनेति। गणपाठसहकृतादिति शेषः॥ साहचर्यादारोपितशौण्डशब्दस्वरूपाणां धूर्तादीनां शौण्डशब्दस्य च तेनाभिधानादित्यन्वयः॥ यथेति। अच्छत्रिषु छत्रित्वारोपेण तत्र प्रयोग इति भावः॥ एवं काकेभ्यो दधीत्यादावपि दध्युपघातकत्वसादृश्येन सर्वेषु काकत्वारोपात्प्रयोग इति बोध्यम्॥ कारकस्य शौण्डादिभिः सामर्थ्यायोगादाह—वृत्त्यन्तरिति। यदि तु यद्द्वारकं यस्य कारकत्वं तदन्वयद्वारैव तस्य क्रियान्वय इत्यङ्गीक्रियते तदा साक्षादपि सामर्थ्यमस्त्येवेति बोध्यम्॥ अन्तःशब्दोत्रेति। मध्यरूपाधिकरणे इत्यर्थकः। वनान्तरित्युदाहरणम्। वनवर्तिमध्ये इत्यर्थस्तस्य। यस्त्वधिकरणशक्तिमात्रवृत्तिस्तेनाव्ययीभाव एवान्तर्वणमिति यथा॥ आधारविवक्षायामिति। आधारत्वविवक्षायामित्यर्थः॥ ३९॥

(२४९ तत्पुरुषसंज्ञासूत्रम्॥ २।१।२ आ. २८॥)

३९० ध्वाङ्क्षेण क्षेपे॥ २। १। ४१॥

(इष्टानुपपत्तिपरिहाराधिकरणम्)

(१२७३ वार्तिकम्॥ १॥)

॥ * ॥ ध्वाङ्क्षेणेत्यर्थग्रहणम्॥ * ॥

(व्याख्याभाष्यम्)

ध्वाङ्क्षेण क्षेपेऽर्थग्रहणं कर्तव्यम्। इहापि यथा स्यात्—तीर्थकाक इति॥

(आक्षेपभाष्यम्)

क्षेप इत्युच्यते। क इह क्षेपो नाम?॥

(प्रदीपः) ध्वाङ्क्षेण॥ ४१॥ आधाराधेयमात्रावगमात् क्षेपासंभवं मत्वा पृच्छति—क इति॥

(समाधानभाष्यम्)

यथा तीर्थकाका न चिरं स्थातारो भवन्ति। एवं यो गुरुकुलानि गत्वा न चिरं तिष्ठति स उच्यते तीर्थकाक इति॥ ध्वाङ्क्षेण॥ ४१॥

(प्रदीपः) उपमानोपमेयभावेन कार्येष्वस्थिरत्वात् क्षेपः समासात्प्रतीयत इत्यर्थः॥ ४१॥

(२५० तत्पुरुषसंज्ञासूत्रम्॥ २।१।२ आ. २९॥)

३९१ कृत्यैर्ऋणे॥ २। १। ४२॥

(इष्टानुपपत्तिपरिहाराधिकरणम्)

(१२७४ वार्तिकम्॥ १॥)

॥ * ॥ कृत्यैर्नियोगे यद्ग्रहणम्॥ * ॥

(व्याख्याभाष्यम्)

कृत्यैर्नियोगे यत्प्रत्ययेनेति वक्तव्यम्। इहापि यथा स्यात्—पूर्वाह्णेगेयं साम, प्रातरध्येयोऽनुवाक इति॥

(प्रदीपः) कृत्यैर्ऋणे॥ ४२॥ पूर्वाह्णेगेयमिति। तत्पुरुषे कृति बहुलमित्यलुक्॥

(उद्द्योतः) कृत्यै॥४२॥ भाष्ये नियोगे इति। आवश्यके इत्यर्थः॥

(आक्षेपभाष्यम्)

तत्तर्हि वक्तव्यम्?॥

(समाधानभाष्यम्)

न वक्तव्यम्। ऋण इत्येव सिद्धम्। इह यद्यस्य नियोगतः कार्यम्, ऋणं तस्य तद्भवति। तत्र ऋण इत्येव सिद्धम्॥

(प्रदीपः) यद्यस्येति। अवश्यकर्तव्यतासामान्यादुपचारादन्यत्राप्यृणशब्दस्य प्रयोगदर्शनाद् गौणस्याप्यर्थस्य शास्त्रे लक्ष्यवशेन क्वचिद् ग्रहणादित्यर्थः॥ ४२॥

(उद्द्योतः) गौणस्याप्यर्थस्येति। ऋणग्रहणमावश्यकोपलक्षणमित्यर्थः॥

(अभ्युपगमभाष्यम्)

यद्ग्रहणं च कर्तव्यम्। इह मा भूत्पूर्वाह्णे दातव्या भिक्षेति॥ कृत्यैः॥ ४२॥

(उद्द्योतः) यद्ग्रहणं चेति। यद्ग्रहणं त्वित्यर्थः॥ ४२॥

(२५१ तत्पुरुषसंज्ञासूत्रम्॥ २।१।२ आ. ३०)

३९५ क्षेपे॥ २। १। ४६॥

(उदाहरणनिर्णयाधिकरणम्)

(आक्षेपभाष्यम्)

किमुदाहरणम्?॥

(समाधानभाष्यम्)

अवतप्तेनकुलस्थितं त एतत्॥

(प्रदीपः) क्षेपे॥ ४६॥ अवतप्तेनकुलेति। चापल्यादिति भावः॥ ४६॥

(आक्षेपभाष्यम्)

क्षेप इत्युच्यते क इह क्षेपो नाम? ॥

(समाधानभाष्यम्)

यथा अवतप्ते नकुलाः न चिरं स्थातारो भवन्ति, एवं कार्याण्यारभ्य यो न चिरं तिष्ठति स उच्यते 'अवतप्तेनकुलस्थितं त एतत्' इति ॥

(आक्षेपभाष्यम्)

क्षेपे सप्तम्यन्तं क्तान्तेन सह समस्यत इत्युच्यते तत्र ते सगतिकेन सनकुलेन च समासो न प्राप्नोति ॥

(समाधानभाष्यम्)

॥ क्षेपे सगतिकसकारकसमासे उक्तम् ॥

किमुक्तम्? । 'क्तग्रहणे गतिकारकपूर्वस्यापि-' इति ॥ क्षेपे ॥ ४६ ॥

(२५१ तत्पुरुषसंज्ञासूत्रम् ॥ २ । १ । २ आ. ३१)

३९६ पात्रेसमितादयश्च ॥ २।१।४७ ॥

(चकारप्रयोजनाधिकरणम्)

(आक्षेपभाष्यम्)

किमर्थश्चकारः? ॥

(समाधानभाष्यम्)

एवकारार्थः । पात्रेसमितादय एव ॥ क मा भूत्? । परमं पात्रे समिता इति ॥ पात्रेसमि ॥४७॥

(प्रदीपः) पात्रे ॥ ४७ ॥ परमं पात्रेसमिता इति । वैयधिकरण्येपि विस्पष्टपटुवत्सुपेति समासः प्राप्नोति ॥ परममिति । क्रियाविशेषणम् । परमाः पात्रेसमिता इति तु पाठो ज्यायान् ॥ ४७ ॥

(२५२ तत्पुरुषसंज्ञासूत्रम् ॥ २ । १ । २ आ. ३२)

३९७ पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन ॥२।१।४८॥

(एकनदीशब्देऽव्ययीभाववारणाधिकरणम्)

(आक्षेपभाष्यम्)

इह कस्मादव्ययीभावो न भवति—एका नदी एकनदी "नदीभिः संख्या" इति प्राप्नोति ॥

(प्रदीपः) पूर्व ॥ ४८ ॥ एकशब्दप्रसङ्गेन नदीभिरित्यत्रोक्तं वस्तु स्मारयितुमाह—इह कस्मादिति ॥

(उद्योतः) पूर्वका ॥ ४८ ॥ भाष्ये—इह कस्मादिति । समाहारद्विगोरिवास्यापि बाध्यसामान्यचिन्तया बाधः स्यादिति प्रश्नः ॥

(समाधानभाष्यम्)

नैष दोषः । इह कश्चित्समासः पूर्वपदार्थप्रधानः । कश्चिदुत्तरपदार्थप्रधानः । कश्चिदन्यपदार्थप्रधानः । कश्चिदुभयपदार्थप्रधानः । पूर्वपदार्थप्रधानोऽव्ययीभावः । उत्तरपदार्थप्रधानस्तत्पुरुषः । अन्यपदार्थप्रधानो बहुव्रीहिः । उभयपदार्थप्रधानो द्वन्द्वः । न चात्र पूर्वपदार्थप्राधान्यं गम्यते ॥

(प्रदीपः) न चात्रेति । एकत्वविशेषणाभावत्र प्राधान्येन प्रतीयते ॥

(उद्योतः) एकत्वविशेषणादिति । एकत्वेन विशिष्टस्य विशेषणत्वादित्यर्थः ॥ नचात्रेति । नदीत्वेन नदी प्रधानं नत्वेकत्वेनेत्यर्थः ॥

(समाधानभाष्यम्)

अथ वाव्ययीभावः क्रियताम्, तत्पुरुष इति, तत्पुरुषो भविष्यति विप्रतिषेधेन ॥

(उद्योतः) विप्रतिषेधेनेति । एकशब्दातिरिक्तसंख्याशब्देऽव्ययीभावस्य चारितार्थ्यमिति भावः ॥

(आक्षेपभाष्यम्)

भवेदेकसंज्ञाधिकारे सिद्धम् । परंकार्यत्वे तु न सिद्ध्यति । आरम्भसामर्थ्याच्चाव्ययीभावः प्राप्नोति, परंकार्यत्वाच्च तत्पुरुषः प्राप्नोति ॥

(समाधानभाष्यम्)

परं कार्यत्वे च न दोषः ॥ कथम्? । नदीभिः समाहारेऽव्ययीभावो वक्तव्यः । स चावश्यं वक्तव्यः । सर्वमेकनदीतरे ॥ पूर्वका ॥ ४८ ॥

इति श्रीमद्भगवत्पतञ्जलिविरचिते व्याकरणमहाभाष्ये द्वितीयस्याध्यायस्य प्रथमे पादे द्वितीयमाह्निकम् ॥

(प्रदीपः) अवशिष्टं भाष्यं तत्रैव व्याख्यातम् ॥ ४८ ॥ इत्युपाध्यायजैयटपुत्रकैयटकृते महाभाष्यप्रदीपे द्वितीयस्याध्यायस्य प्रथमे पादे द्वितीयमाह्निकम् ॥

(उद्योतः) समाहारे इति । स च नात्रेति भावः ॥ ४८ ॥ इति शिवभट्टसुतसतीगर्भजनागेशभट्टकृते भाष्यप्रदीपोद्योते द्वितीयाध्यायस्य प्रथमे पादे द्वितीयमाह्निकम् ॥

द्वितीयाध्यायस्य प्रथमपादे तृतीयाह्निकम्

(२५४ तत्पुरुषसंज्ञासूत्रम् ॥ २।१।३ आ. १)

३९९ तद्धितार्थोत्तरपदसमाहारे च ॥ २।१।५० ॥

(समाहारशब्दार्थनिर्णयाधिकरणम्)

(आक्षेपभाष्यम्)

समाहार इति कोयं शब्दः ? ॥

(प्रदीपः) **तद्धितार्थो** ॥ ५० ॥ **समाहार इति कोयमिति**। किं भावसाधनोऽथ कर्मसाधनः। तत्र भावसाधने द्रव्यस्यानयनादिकं न प्राप्नोति। समूहरूपत्वाच्च समाहारस्य तद्धितार्थग्रहणेन समासस्य सिद्धत्वाद्भेदेनोपादानमनर्थकं प्राप्नोति। कर्मसाधने तु उपसर्जनह्रस्वत्वं न प्राप्नोति **द्विगुरेकवचन**मित्येतच्च वक्तव्यं भवतीति प्रश्नः ॥

(उद्योतः) **तद्धितार्थो** ॥ ५० ॥ **इत्येतच्च वक्तव्यमिति**। समाह्रियमाणानां प्रधानानां बहुत्वादिति भावः ॥

(समाधानभाष्यम्)

समाङ्पूर्वाद्धरतेः कर्मसाधनो घञ्—समाह्रियते समाहार इति ॥

(प्रदीपः) **कर्मसाधन इति**। द्रव्यस्यैव कार्यसंबन्धदर्शनादिति भावः। संज्ञाग्रहणं च घञ्विधौ प्रत्याख्यातमित्यसंज्ञायामपि घञ् भवति ॥

(आक्षेपभाष्यम्)

यदि कर्मसाधनः, पञ्च कुमार्यः समाहृताः पञ्चकुमारि दशकुमारि "गोस्त्रियोरुपसर्जनस्य" इति ह्रस्वत्वं न प्राप्नोति। "द्विगुरेकवचनम्" इत्येतच्च वक्तव्यम् ॥

(प्रदीपः) **यदीति**। कुमार्यर्थस्य प्राधान्यात् समासशास्त्रे च प्रथमानिर्देशाभावाद् ह्रस्वाप्रसङ्गः। यद्यप्यत्र नपुंसकह्रस्वत्वं सिध्यति पञ्चखट्वीति तु न सिध्यति। अत्र हि **यावन्त** इति पक्षे स्त्रीत्वम्। पक्षे क्लीबत्वम्। तत्र क्लीबत्वे ह्रस्वत्वे सति पञ्चखट्वमिति सिध्यति। स्त्रीत्वे तु अनुपसर्जनत्वात् अह्रस्वत्वेऽनदन्तत्वाद् ङीबभावात् पञ्चखट्वा इति स्यात् ॥ **द्विगुरिति**। अनेकार्थत्वात्समासस्येति भावः ॥

(उद्योतः) **कुमार्यर्थस्य प्राधान्यादिति**। एवं च प्रधानत्वेन नानाक्रियासम्बन्धयोग्यतया नानाविभक्त्युत्पत्तेरेकविभक्तीति नोपसर्जनत्वमिति भावः॥ **पक्षे क्लीबत्वमिति**। एवं च क्लीबत्वेप्यनुपसर्जनत्वादह्रस्वत्वेऽनदन्तत्वात् ङीबभावे पञ्चखट्वा इति स्यादिति तात्पर्यम्। क्वचित्तु मूल एवेदं दृश्यते॥ **परे तु** नात्र नपुंसकह्रस्वप्राप्तिः एतद्भाष्यप्रामाण्येनास्यार्धर्चादित्वेन पुंस्त्वस्यापि स्वीकारात्। पञ्चकुमारिरित्यत्र विसर्गो लेखकप्रमादाद् भ्रष्टः। अत एव **स नपुंसकमिति** शास्त्रं **विभाषा वृक्षेति** सूत्रे लिङ्गमशिष्यमित्यादिना प्रत्याख्यातम्। व्यभिचारदर्शनात्तत्र कार्यमिति तदाशयः। अन्यथा संख्यादेरपि लोकाश्रयत्वात् अत्रैव तत् कथं नेत्यलम् ॥

(समाधानभाष्यम्)

एवं तर्हि भावसाधनो भविष्यति—समाहरणं समाहारः ॥

(आक्षेपभाष्यम्)

अथ भावसाधने सति किमभिधीयते ? ॥

(प्रदीपः) **अथेति**। लोके समाहार एकप्रदेशसंघट्टनमुच्यते। तस्य पञ्चग्राम्यादावसंभव इति भावः ॥

(समाधानभाष्यम्)

यत्तदौत्तराधर्यम् ? ॥

(प्रदीपः) **यत्तदिति**। पञ्चपूल्यादौ तस्य संभवादिति भावः ॥

(आक्षेपभाष्यम्)

कः पुनर्गवां समाहारः ॥

(प्रदीपः) **कः पुनरिति**। औत्तराधर्यस्यासंभवात्प्रश्नः ॥

(समाधानभाष्यम्)

यत्तदर्जनं क्रयणं भिक्षणमपहरणं वा ॥

(प्रदीपः) **यत्तदर्जनमिति**। एकस्यां क्रियायां गुणे वा बुद्ध्या समीपीकरणं समाहार इत्यर्थो विवक्षितः। तत्रार्जननिमित्तत्वादर्जनं समाहार इत्युक्तम्। तच्च क्रयादिना भवतीति तन्निर्देशः कृतः ॥

(उद्योतः) **बुद्ध्या** हस्तादिवत्करणभूतया **एकस्यां क्रियायां** क्रियारूपे वस्तुनि **समीपीकरणं** संघट्टनमित्यर्थः ॥ **अर्जननिमित्तत्वादिति**। बहुव्रीहिः, अर्जने हि एतावन्मयेदमर्जितमित्येकक्रियायां संघट्टनं भवतीति भावः ॥ **अर्जनं** स्वस्वत्वाक्रान्तताकरणम् ॥

(आक्षेपभाष्यम्)

यद्येवं विक्षिप्तेषु पूलेषु, गोषु चरन्तीषु न सिद्ध्यति ॥

(प्रदीपः) यथोक्तमप्रतिपद्यमानः पर आह—**यद्येवमिति** ॥ **गोष्विति**। नानास्वामिकानामर्जनाभावमाह ॥

(उद्योतः) भाष्ये—**विक्षिप्तेष्विति**। विक्रयार्थं विक्षिप्य स्थापितेष्वित्यर्थः। तत्र नौत्तराधर्यमिति भावः ॥

(समाधानभाष्यम्)

एवं तर्हि समभ्याशीकरणं समाहारः ॥

(प्रदीपः) समभ्याशीकरणमिति । समीपीकरणमित्यर्थः ॥

(उद्द्योतः) समीपीकरणमित्यर्थ इति । तच्चैकदेशे क्रियायां बुद्धौ वेत्यन्यत् ॥

(आक्षेपभाष्यम्)

एवमपि पञ्चग्रामी षण्णगरी त्रिपुरीति न सिध्यति ॥ किं कारणम्? । समेकत्ववाची, आङाभिमुख्ये वर्तते, हरतिर्देशान्तरप्रापणे ॥

(प्रदीपः) एवमपीति । ग्रामादीनां नियतदेशावस्थानत्वात्समीपीकरणाभाव इति भावः । यदायं ग्रामशब्दो देशविशेषवाची तदायं दोषः । पुरुषवाचिनि तु न दोषः । तेषां समीपीकरणसंभवात् ॥ समेकत्ववाचीति । भिन्नदेशानामेकवर्गीकरणेन देशान्तरप्रापणं समाहारः । स च ग्रामादीनां नास्तीति भावः ॥

(उद्द्योतः) एकवर्गीकरणेनेति । फलरूपे हेतौ तृतीया । आभिमुख्यार्थाङा वर्गीकरणं लभ्यम् ॥

(समाधानभाष्यम्)

नावश्यं हरतिर्देशान्तरप्रापण एव वर्तते ॥ किं तर्हि? ॥ सादृश्येपि वर्तते । तद्यथा—मातुरनुहरति पितुरनुहरतीति ॥

(प्रदीपः) नावश्यमिति । ततश्च ग्रामादीनामपि लाभादिसदृशधर्मानुगमात्समाहारसद्भावः ॥

(उद्द्योतः) भाष्ये—सादृश्येपि वर्तत इति । एकक्रियाकारकत्वादिरूपं सादृश्यमेव समाहारशब्दार्थः अनुहरतिवत् ॥

(समाधानान्तरभाष्यम्)

अथ वा पञ्चग्रामी षण्णगरी त्रिपुरीति । नैवेदमियत्येवावतिष्ठते । अवश्यमसौ ततः किंचिदाकाङ्क्षति क्रियां गुणं वा । यदाकाङ्क्षति तदेकं, स च समाहारः ॥

(प्रदीपः) अथ वेति । केवलेन पदार्थेन व्यवहाराभावादवश्यं क्रिया गुणो वापेक्ष्यते तत्र च बुद्ध्या भिन्नदेशानामप्यस्ति समीपीकरणमित्यर्थः ॥ स च समाहार इति । तन्निमित्तत्वादित्यर्थः ॥

(उद्द्योतः) नन्वनुपूर्वकस्यैव तत्र शक्तिरत आह—भाष्ये—अथ वेति ॥ नैवेदमिति । पञ्चग्रामीत्यादिपदं, इयमिति पाठे उक्तिरिति शेषः ॥ इयत्येव । पञ्चग्रामादिमात्र एव ॥ असौ । प्रयोक्ता द्रष्टा वा ॥ ततः । ग्रामादितः । अतिरिक्तं इति शेषः ॥ आकाङ्क्षति । बोधयितुम् ॥ क्रियां, नदीतीरस्थत्वादिरूपाम् ॥ गुणं, समृद्धत्वादिरूपम् ॥ तत्र च बुद्ध्येति । तत्र क्रियादौ बुद्ध्या करणभूतया तेषां सामीप्यं संघट्टनं क्रियत इत्यर्थः ॥

(आक्षेपभाष्यम्)

अयं तर्हि भावसाधने सति दोषः—'पञ्चफली आनीयताम्' इति भावानयने चोदिते द्रव्यानयनं न प्राप्नोति ॥

(समाधातुं प्रश्नभाष्यम्)

नैष दोषः । इदं तावदयं प्रष्टव्यः—'अथेह "गौरनुबन्ध्योऽजोऽग्नीषोमीयः" इति कथमाकृतौ चोदितायां द्रव्ये आरम्भणालम्भनप्रोक्षणविशसनानि क्रियन्ते' इति ॥

(तदेवप्रश्नोत्तरभाष्यम्)

"असंभवाद्" आकृतौ आरम्भणादीनां संभवो नास्तीति कृत्वा आकृतिसहचरिते द्रव्ये आरम्भणादीनि क्रियन्ते ॥

(प्रश्नोत्तरस्यैव स्वार्थसाधकताभाष्यम्)

इदमप्येवंजातीयकमेव । असंभवाद्भावानयनस्य द्रव्यानयनं भविष्यति ॥ अथ वा—अव्यतिरेकाद् द्रव्याकृत्योः ॥

(प्रदीपः) असंभवादिति । द्रव्यानयनमन्तरेणेत्यर्थः ॥ अथ वेति । पूर्वमुपायभावेनाद्यानयने पात्रस्येव द्रव्यस्य क्रियायामनुप्रवेशः कथितः ॥ इदानीं तु वास्तवभेदाभावाद् बुद्धिपरिकल्पितभेदसद्भावादिति विशेषः ॥

(उद्द्योतः) असम्भवादिति । जातेरेवानयनान्वयः क्रिया तु तत्रासम्भवात्तत्सम्बद्धे द्रव्ये इति द्रव्यद्वारा तदानयनादिति भावः । तद्ध्वनयन्नाह—अग्न्यानयने पात्रस्येवेति । अग्निरानेय इति बोधिते शब्दाबुद्धपात्रस्यापि यथा आनयनं केवलतदानयनासम्भवात्तथेहापीति भावः । मञ्जूषायां चेदमुपपादितम् ॥ वास्तवभेदाभावादिति । द्रव्याकृत्योरिव समाहारसमाह्रियमाणयोरपि वास्तवभेदाभाव इति भावः ॥ नन्वेवं घटानां समाहार इति न स्यादत आह—बुद्धिपरिकल्पितेति । यतोयं बुद्धिकल्पितोऽतो वास्तवभेदस्यैवाभाव इति भावः ॥ अव्यतिरेकादित्यस्य व्यतिरेकमात्रस्याभावादित्यर्थ इति भावः ॥

(सूत्रन्यासविचाराधिकरणम्)

(आक्षेपभाष्यम्)

किं पुनर्द्विगुसंज्ञा प्रत्ययोत्तरपदयोर्भवति? ॥

(प्रदीपः) किं पुनरिति । काशकृत्स्नस्य "प्रत्ययोत्तरपदयोः" इति सूत्रम् । तद्विचारयति । पाणिनीयं तु पश्चाद्विचारयिष्यति ॥

(अभ्युपगमभाष्यम्)

एवं भवितुमर्हति ॥

(प्रदीपः) दोषस्य सुप्रतिविधानत्वादाह—एवमिति ॥

(१२७५ अभ्युपगमे दोषवार्तिकम् ॥ १ ॥)

॥ * ॥ द्विगुसंज्ञा प्रत्ययोत्तरपदयोश्चेदितरेतराश्रयत्वादप्रसिद्धिः ॥ * ॥

(व्याख्याभाष्यम्)

द्विगुसंज्ञा प्रत्ययोत्तरपदयोश्चेदितरेतराश्रयत्वादप्रसिद्धिः ॥ का इतरेतराश्रयता? । द्विगुसंज्ञानिमित्ते प्रत्ययोत्तरपदे । प्रत्ययोत्तरपदनिमित्ता च द्विगुसंज्ञा । तदेतदितरेतराश्रयं भवति । इतरेतराश्रयाणि च कार्याणि न प्रकल्पन्ते ॥

(प्रदीपः) **द्विगुसंज्ञानिमित्ते इति** । पञ्चसु कपालेषु संस्कृत इति समासे सति प्रातिपदिकत्वान् प्रत्ययेन भाव्यम् प्रत्यये च परतो द्विगुरितीतरेतराश्रयः । पञ्च गावो धनमस्येत्यत्रापि पदद्वयस्य तत्पुरुषे कृते बहुव्रीहिः क्रियते इति पक्षाश्रयेणेतरेतराश्रयोद्भावनम् । धनशब्दस्य सत्युत्तरपदत्वे पूर्वयोः पदयोः समासेन भवितव्यम् । सति च पदद्वयस्य समासे बहुव्रीहिणा, तस्मिन्सति धनशब्दस्योत्तरपदत्वेन । सुप्सुपेति संख्याया विवक्षितत्वात् त्रयाणां पदानां बहुव्रीहिणा न भवितव्यमिति मन्यते । यदा त्वनेकग्रहणात्पदत्रयस्यापि बहुव्रीहिर्भवति तदा नास्तीतरेतराश्रयदोषः ॥ अथ वायं भावः—समास इत्यन्वर्थसंज्ञेयं समसनं समासः संक्षेपः । स चासंक्षिप्तानां क्रियते । यदि च पूर्वं बहुव्रीहिः प्रवर्तते तदा संक्षिप्तत्वादेकार्थीभावात् किमपरः संक्षेपः क्रियते । तस्मात्तत्पुरुषगर्भो बहुव्रीहिः कर्तव्यस्तत्र चेतरेतराश्रयत्वम् ॥

(उद्योतः) द्विगोरित्येवमेविधानात्कथं प्रत्ययो द्विगुनिमित्तोत आह—**पञ्चस्विति** । द्विगुनिमित्तप्रातिपदिकत्वनिमित्तत्वात्तन्निमित्तत्वमिति भावः ॥ नन्वेवमप्युत्तरपदेन सः द्विगोरुत्तरपदनिमित्तत्वेपि बहुव्रीहेस्त्रयाणामपि भावेन उत्तरपदत्वस्य द्विगुनिमित्तत्वाभावादत आह—**पञ्चगाव इति** ॥ तत्पुरुषे कृत एव बहुव्रीहिर्न प्रागिति कुतोत आह—**सुप्सुपेति** । संख्याया विवक्षितत्वमुपलक्षणं सुबन्तत्वं समुदाये न पर्याप्तमित्यस्यार्थस्य ॥ अविशेषेण बहुव्रीहिरिति पक्षेप्याह—**अथ वेति** ॥ संक्षिप्तत्वे हेतुरेकार्थीभावादिति ॥

(समाधानभाष्यम्)

एवं तर्हि "अर्थे" इति वक्ष्यामि ॥

(प्रदीपः) पाणिनीयलक्षणं निरूपयितुमाह—**एवं तर्हीति** । तद्धितार्थे तद्धिताभिधेये अनुत्पन्न एव तद्धिते द्विगुरिति नास्त्यन्योन्याश्रयत्वमितिभावः ॥

(उद्योतः) अर्थशब्दो न प्रयोजनवाचीत्याह—**तद्धिताभिधेय इति** । तत्र वाच्ये समास त्यर्थः ॥

(१२७६ वार्तिकम् ॥ २ ॥)

॥ * ॥ अर्थे चेत्तद्धितानुत्पत्तिर्बहुव्रीहिवत् ॥ * ॥

(व्याख्याभाष्यम्)

अर्थे चेत्तद्धितोत्पत्तिर्न प्राप्नोति । द्वैमातुरः । त्रैमातुरः । पाञ्चनापितिः ॥ किं कारणम्? । द्विगुनोक्तत्वात् । बहुव्रीहिवत् । तद्यथा—चित्रगुः शबलगुरिति बहुव्रीहिणोक्तत्वान्मत्वर्थस्य मत्वर्थीयो न भवति ॥

(प्रदीपः) **अर्थे चेदिति** । यदि तद्धितार्थेभिधेये समासः क्रियते तदा समासेन तस्यार्थस्याभिहितत्वात्प्रकृत्यर्थव्यतिरिक्तप्रत्ययार्थाभावात् पाञ्चनापितिरित्यादौ तद्धितो न प्राप्नोति ॥

(उद्योतः) **प्रकृत्यर्थव्यतिरिक्तप्रत्ययार्थाभावादिति** । वाचकप्रत्ययस्थले स आवश्यक इति भावः ॥

(न्यासान्तरभाष्यम्)

एवं तर्हि "समासतद्धितविधौ" इति वक्ष्यामि ।

(प्रदीपः) **समासतद्धितविधाविति** । न्यासद्वये दोषदर्शनान्न्यासान्तरमाश्रीयते । समासे विधीयमाने तद्धिते च दिक्संख्ये सुपा सह समस्येते इति लक्षणाश्रयान्नास्तीतरेतराश्रयदोषः । परनिमित्तानपेक्षणात्तद्विषये प्रागेव समासविधानादिति भावः ॥

(उद्योतः) द्वितीयं दोषमुद्धर्तुमाह—**परनिमित्तेत्यादि** ॥

(१२७७ वार्तिकम् ॥ ३ ॥)

॥ * ॥ समासतद्धितविधाविति चेदन्यत्र समाससंज्ञाभावः ॥ * ॥

(व्याख्याभाष्यम्)

समासतद्धितविधाविति चेदन्यत्र समाससंज्ञा न प्राप्नोति ॥ कान्यत्र? । स्वरे । पञ्चारत्निः दशारत्निः "इगन्ते द्विगौ" इत्येष स्वरो न प्राप्नोति ॥

(प्रदीपः) **अन्यत्रेति** । यथा स्वरे पराङ्गवद्भावो विधीयमानः षत्वणत्वयोर्न भवति एवं स्वरे द्विगुसंज्ञा न स्यात् । इगन्तेति च लक्षणं समाहारद्विगौ सावकाशम् । यानि तु **द्विगोर्लुगनपत्य** इत्यादीनि तेषु वचनसामर्थ्याद् द्विगुसंज्ञा प्रवर्तत इत्यभिप्रायेणान्यत्र सावकाशे स्वरे दोष उक्तः ॥ **पञ्चारत्निरिति** । पञ्चारत्नयः प्रमाणमस्येति **प्रमाणे लो द्विगोर्नित्यमिति** मात्रचो लुक् ॥

(उद्योतः) **यानि तु द्विगोरिति** । द्विगोः परस्य तद्धितस्य लुगिति सूत्रार्थे तु समाहारद्विगोः परस्य तद्धितस्य लुगर्थमिदमपि सावकाशमेवार्थविशेषासंप्रत्ययेऽतन्निमित्तादपीति वार्तिकाद् द्विगोर्निमित्तं यस्तद्धित इत्यर्थे तु तत्र दोषस्यैवाभाव इति चिन्त्यम्॥

(१२७८ समाधानवार्तिकम् ॥ ४ ॥)

॥ * ॥ सिद्धं तु प्रत्ययोत्तरपदयोश्चेति वचनात् ॥ * ॥

(व्याख्याभाष्यम्)

सिद्धमेतत् ॥ कथम् ? । प्रत्ययोत्तरपदयोश्चेति वचनात् । प्रत्ययोत्तरपदयोर्द्विगुसंज्ञा भवतीति वक्तव्यम् ॥

(प्रदीपः) सिद्धं त्विति । पाञ्चनापितिः पञ्चगवधन इति च स्थितानामेव शब्दानामनुशासनं क्रियते । तत्र प्रत्ययोत्तरपदे स्थिते एवेति नास्ति दोषः ॥

(आक्षेपस्मारणभाष्यम्)

ननु चोक्तम्—*द्विगुसंज्ञा प्रत्ययोत्तरपदयोश्चेदितरेतराश्रयत्वादप्रसिद्धिः* इति ॥

(समाधानसाधकभाष्यम्)

नैष दोषः । इतरेतराश्रयमात्रमेतच्चोदितम् । सर्वाणि चेतरेतराश्रयाण्येकत्वेन परिहृतानि—*सिद्धं तु नित्यशब्दत्वाद्* इति ॥

(समाधानबाधकभाष्यम्)

नेदं तुल्यमन्यैरितरेतराश्रयैः । नहि संज्ञा नित्या ॥

(प्रदीपः) नहि संज्ञेति । प्रत्ययसंज्ञासंबन्धं समाससंज्ञाप्रतिबद्धं चोत्तरपदत्वमाश्रित्यायं समासः क्रियते न च प्रत्ययसमाससंज्ञे लोके स्तः ॥

(उद्द्योतः) प्रत्ययसंज्ञासम्बन्धमिति । प्रत्ययशब्देनोपादानादिति भावः ॥ लोके स्त इति । नित्यत्वेपि संज्ञानां तदीयसंकेतग्रहस्य शास्त्रनिरपेक्षं लोकेऽसत्त्वमिति भावः ॥

(समाधानसाधकभाष्यम्)

एवं तर्हि भाविनी संज्ञा विज्ञास्यते । तद्यथा । कश्चित्कंचित्तन्तुवायमाह—"अस्य सूत्रस्य शाटकं वय" इति। स पश्यति—'यदि शाटकः न वातव्यः। अथ वातव्यो न शाटकः । वातव्यः शाटकश्चेति विप्रतिषिद्धं भवति । भाविनी खल्वस्य संज्ञाभिप्रेता। स मन्ये वातव्यः यस्मिन्नुते 'शाटक' इत्येतद्भवति' इति॥ एवमिहापि तस्मिन् द्विगुर्भवति यस्याभिनिर्वृत्तस्य प्रत्यय उत्तरपदमिति चैते संज्ञे भविष्यतः ॥

(प्रदीपः) एवं तर्हीति । प्रत्ययोत्तरपदयोरिति विषयसप्तमी न तु परसप्तमीत्यत्र तात्पर्यम् ॥

(उद्द्योतः) भाष्ये—एते संज्ञे इति । उत्तरपदशब्दोपि समाससंज्ञानिमित्तकत्वात्संज्ञैवेति भावः ॥

(अभ्युपगमभाष्यम्)

अथ वा पुनरस्तु—'अर्थे' इति ॥

(प्रदीपः) पाणिनीयं समर्थयितुमाह—अथ वेति । तद्धितश्चासावर्थः प्रयोजनं तस्मिन् कर्तव्ये द्विगुर्भवतीत्यर्थः ॥

(आक्षेपस्मारणम्)

ननु चोक्तम्—*अर्थे चेत्तद्धितानुत्पत्तिर्बहुव्रीहिवद्* इति ॥

(समाधानभाष्यम्)

नैष दोषः। नावश्यमर्थशब्दोभिधेय एव वर्तते॥ किं तर्हि ?। स्यादर्थेपि वर्तते । तद्यथा—दारार्थं घटामहे। धनार्थं भिक्षामहे। दारा नः स्युः। धनानि नः स्युरिति। एवमिहापि तद्धितार्थे द्विगुर्भवतीति तद्धितः स्यादिति ॥

(प्रदीपः) स्यादिति । प्रार्थने लिङ् ॥

(१२७९ वार्तिकम् ॥ ५ ॥)

॥ * ॥ द्विगोर्वा लुग्वचनं ज्ञापकं तद्धितोत्पत्तेः ॥ * ॥

(व्याख्याभाष्यम्)

अथ वा यदयं "द्विगोर्लुगनपत्ये" इति द्विगोरुत्तरस्य तद्धितस्य लुकं शास्ति तज्ज्ञापयत्याचार्यः—'उत्पद्यते द्विगोस्तद्धितः' इति ॥

(प्रदीपः) अत्रापि पक्षे स्वरे द्विगुसंज्ञा न प्राप्नोतीत्याह—द्विगोरिति । अभिधेयवचनेप्यर्थशब्दे तद्धितानुत्पत्तिदोषो नास्तीत्यर्थः ॥

(उद्द्योतः) द्विगोर्वा लुग्वचनं ज्ञापकमिति । एवं तद्धितार्थे विषयभूत इत्यर्थेन च सिध्यति। न चात्र पक्षे अर्थग्रहणं व्यर्थं तद्धिते विषयभूत इत्येव वक्तुं युक्तत्वादिति वाच्यम् । स्वरे दोषप्रसङ्गात् । वस्तुतो ज्ञापकेनायमेवार्थो बोध्यत इति बोध्यम् ॥

(समाहारग्रहणसार्थक्याधिकरणम्)

(१२८० वार्तिकम् ॥ ६ ॥)

॥ * ॥ समाहारसमूहयोरविशेषात्समाहारग्रहणानर्थक्यं तद्धितार्थेन कृतत्वात् ॥ * ॥

(व्याख्याभाष्यम्)

समाहारः समूह इत्यविशिष्टावेतावर्थौ । समाहारसमूहयोरविशेषात्समाहारग्रहणमनर्थकम् ॥ किं कारणम्!। तद्धितार्थेन कृतत्वात् । 'तद्धितार्थे द्विगुः' इत्येवमत्र द्विगुर्भविष्यति ॥

(प्रदीपः) समाहारसमूहयोरिति । स्वरूपपदार्थकत्वाद्भिन्नार्थत्वादेकशेषाभावः ॥ अविशेषादिति । एकार्थत्वादित्यर्थः ॥

(उद्द्योतः) भिन्नार्थत्वे हेतुः स्वरूपेत्यादिः ॥

(आक्षेपभाष्यम्)

यदि 'तद्धितार्थे द्विगुः' इत्येवमत्र द्विगुर्भविष्यति, तद्धितोत्पत्तिः प्राप्नोति ॥

(आक्षेपबाधकभाष्यम्)

उत्पद्यताम्। लुक् भविष्यति ॥

(आक्षेपसाधकभाष्यम्)

लुक्कृतानि प्राप्नुवन्ति ॥ कानि? । पञ्चपूली दशपूली "अपरिमाणबिस्ताचितकम्बल्येभ्यो न तद्धितलुकि" इति प्रतिषेधः प्राप्नोति ॥

पञ्चगवं दशगवम् "गोरतद्धितलुकि" इति टच् न प्राप्नोति ॥

(प्रदीपः) प्रतिषेधः प्राप्नोतीति। यथा पञ्चभिरश्वैः क्रीता पञ्चाश्वेति ॥

(समाधानभाष्यम्)

नैष दोषः। अविशेषेण 'द्विगोर्ङीब् भवति' इत्युक्त्वा "अपरिमाणबिस्ताचितकम्बल्येभ्यः समाहारे" इति वक्ष्यामि तन्नियमार्थं भविष्यति 'समाहार एव नान्यत्र' इति ॥

गोरकारो द्विगोः समाहारे ॥

अविशेषेण 'गोष्टज् भवति' इत्युक्त्वा 'द्विगोः समाहारे' इति वक्ष्यामि तन्नियमार्थं भविष्यति—'समाहार एव नान्यत्र' इति ॥

(प्रदीपः) अपरिमाणेति। न तद्धितलुकि, 'अतद्धितलुकी' त्यपास्य सूत्रद्वयेपि समाहारग्रहणं क्रियते समाहार एव तद्धितलुकि ङीप्समासान्तौ भवतो नान्यत्रेति नियमविधानान्नास्तिदोषः ॥ अविशेषेणेति। गोरित्येकं सूत्रं क्रियते। गोशब्दान्तस्य तत्पुरुषस्य टज् भवति ब्राह्मणगव इति। ततो द्विगोः समाहार इति द्वितीयं सूत्रं नियमार्थमित्यर्थः ॥

(उद्द्योतः) समाहार एव तद्धितलुकीति। नियमस्य सजातीयापेक्षत्वात्। तेन पञ्चगवधन इत्यादौ टच्सिद्धिरिति भावः ॥ भाष्ये द्विगोः समाहारइति। अनवयवभूतद्विगोश्चेत्समाहार एवेत्यर्थः। तेन पञ्चगवधनमित्यस्य सिद्धिः ॥

(१२६१ वार्तिकम् ॥ ७ ॥)

॥ * ॥ अभिधानार्थं तु ॥ * ॥

(व्याख्याभाष्यम्)

अभिधानार्थं तु समाहारग्रहणं कर्तव्यम्। समाहारेणाभिधानं यथा स्यात्, तद्धितार्थेन मा भूदिति ॥ किं च स्यात्? ॥ तद्धितोत्पत्तिः प्रसज्येत ॥

(प्रदीपः) अभिधानार्थे त्विति। समासेन समाहारस्याभिधानं यथा स्यात्। तद्धितेन मा भूदित्यर्थः ॥ समाहारेणेति। समाहारेऽभिधेये द्विगुरित्यभिधानं यथा स्यात्। एवं चाभिधाने समासेनोक्तत्वात्तद्धितो नोत्पद्यते ॥ तद्धितार्थेनेति। तद्धितार्थे द्विगुरित्यभिधानं मा भूदित्यर्थः। एवमभिधाने हि तद्धितः स्यात्। अर्थशब्दस्य स्वादर्थत्वाज्ज्ञापकाद्वा ॥

(उद्द्योतः) समाहारेणेति। समाहारेण समाहारशब्दप्रतिपाद्येनाभिधानं विधानं यथा स्यादित्यर्थः। एवं तद्धितार्थेन तद्धितार्थशब्दप्रतिपाद्येनेत्यर्थः ॥ तत्फलितमाह—समाहारेऽभिधेय इति ॥ एवं च समाहारशब्देनेव समासेनापि तस्य तस्य पुंस्त्वेनैव बोधः। नपुंसकत्वातिदेशात्तु तत्प्रयुक्तं कार्यमात्रमिति बोध्यम् ॥

(अतिप्रसङ्गबाधकभाष्यम्)

उत्पद्यताम्। लुग् भविष्यति ॥

(लुकिदूषणभाष्यम्)

लुक्कृतानि प्राप्नुवन्ति ॥

(लुकिदूषणपरिहारभाष्यम्)

सर्वाणि परिहृतानि ॥

(दूषणपरिहारबाधकभाष्यम्)

न सर्वाणि परिहृतानि। पञ्चकुमारि दशकुमारि "लुक् तद्धितलुकि" इति ङीपो लुक् प्रसज्येत ॥

(अवान्तरसमासविधानाधिकरणम्)

(१२६२ विधानान्तरवार्तिकम् ॥ ८ ॥)

॥ * ॥ द्वन्द्वतत्पुरुषयोरुत्तरपदे नित्यसमासवचनम् ॥ * ॥

(भाष्यम्) द्वन्द्वतत्पुरुषयोरुत्तरपदे नित्यसमासो वक्तव्यः। वाग्दृषदप्रियः। छत्रोपानहप्रियः। पञ्चगवप्रियः। दशगवप्रियः ॥ किं प्रयोजनम्?। समुदायवृत्ताववयवानां मा कदाचिदवृत्तिर्भूदिति ॥

(प्रदीपः) उत्तरपदप्रसङ्गेन विचारान्तरमाह—द्वन्द्वेति॥ वाग्दृषदप्रिय इति। वाक् च दृषच्च प्रिये अस्य पञ्च गावः प्रिया अस्येति त्रिपदे बहुव्रीहौ कृते उत्तरपदे परतो महाविभाषाधिकाराद्विकल्पेन द्वन्द्वतत्पुरुषौ प्राप्तौ नित्यौ तु वक्तव्यौ। अन्यथा समासाभावपक्षे समासान्तो न स्यात्। जातिरप्राणिनामिति चात्र समाहारद्वन्द्वः। यदि त्वितरेतरयोगेप्यत्र द्वन्द्वः स्यात् तदा कार्ये नैव भेदः स्यात् ॥ समुदायवृत्ताविति। बहुव्रीहावित्यर्थः ॥

(उद्द्योतः) तदा कार्ये नैव भेदः स्यादिति। स्वरे भेदस्य सत्त्वात्समर्थसूत्रभाष्ये उक्तत्वाच्च चिन्त्यमेतत् ॥ कश्चित्तु

रूपे नैव भेदः स्यादिति पाठः। कचित्तु कार्येणैवेति पाठः। स्वरूपकार्येणैव भेदो न तु रूपेणेत्यर्थः॥ भाष्ये—**अवयवानामिति**। द्वन्द्वतत्पुरुषविषयाणामित्यर्थः॥

(आक्षेपभाष्यम्)

तत्तर्हि वक्तव्यम्?॥

(समाधानभाष्यम्)

न वक्तव्यम्। इह द्वौ पक्षौ वृत्तिपक्षश्चावृत्तिपक्षश्च। यदा वृत्तिपक्षः तदा सर्वेषामेव वृत्तिः। यदाऽवृत्तिः पक्षः तदा सर्वेषामवृत्तिः॥

(प्रदीपः) **वृत्तिपक्ष इति**। एकार्थीभाव इत्यर्थः। न च समुदायस्यैकार्थीभावे तदभावोऽवयवयोर्युक्तः। विरोधादित्यर्थः॥ **यदाऽवृत्तिरिति**। द्वन्द्वतत्पुरुषभाविनां पदानां यदा व्यपेक्षालक्षणं सामर्थ्यं तदा बहुव्रीहिर्न भवतीत्यर्थः॥

(उद्द्योतः) **तदभावोऽवयवयोरिति**। न चैकार्थीभावेऽपि विभाषानुवृत्तिसामर्थ्यात्समासविकल्पोऽस्तु तस्य सर्वत्र सामर्थ्येनैव सम्बन्धस्य क्रमतया समासेनासम्बन्धात्॥ नन्वेवं द्वन्द्वयोग्यपदयोर्निष्कृष्य चार्थान्तर्भावेणैकार्थीभावे मानाभावः, पदत्रयस्यैव तथैकार्थीभावकल्पनात्। एवं च द्वन्द्वो दुर्लभः। इदं वचनं तु प्रत्याख्यातम्। चार्थे इति सूत्रं तु धवखदिरावित्यादौ चरितार्थम्। किं चैवं द्वौ मुनी वंश्यौ प्रियौ यस्येति बहुव्रीहौ पूर्वयोरव्ययीभावापत्तिः। तथा च स्वरे दोषः। एवं द्विस्त्रिशत्प्रिया अस्येति शैषिकबहुव्रीहौ **संख्ययाव्यये**त्यवान्तरबहुव्रीह्यापत्तौ **बहुव्रीहौ संख्येये**ति डजापत्तिः सुचः श्रवणानापत्तिश्चेति चेन्न। निष्कृष्यैकार्थीभावस्यैव समासादिनिमित्तत्वे मानाभावात् समासान्तरं त्वनभिधानान्नेति अधिकपटिवर्षप्रसङ्गेन **समर्थसूत्र**शेषे भाष्ये ध्वनितम्। द्वन्द्वोऽपि बहुव्रीह्यवयव एव, न द्वन्द्वावयव इति द्वौनृपोढनेष्टोद्गातार इति भाष्येण ध्वनितम्। नव्यानां तत्र प्रमाद एवेति दिक्।

(१२८३ बहूनांतत्पुरुषविधायकवार्तिकम् ॥ ९ ॥)

॥ * ॥ उत्तरपदेन परिमाणिना द्विगोः समासवचनम् ॥ * ॥

(भाष्यम्) **उत्तरपदेन परिमाणिना द्विगोः समासो वक्तव्यः। द्वौ मासौ जातस्य यस्य सः द्विमासजातः त्रिमासजातः॥ किं पुनः कारणं न सिद्ध्यति!। सुप्सुपेति वर्तते॥**

(प्रदीपः) **द्विगोरिति**। द्विगोर्निष्पत्तय इत्यर्थः॥ **द्वौ मासौ जातस्येति**। **कालाः परिमाणिनेति** त्रिपदः समास इष्यते। स च सुप्सुपेति संख्याया विवक्षितत्वान्न प्राप्नोति। तस्मिंश्च कृते उत्तरपदे परतो द्विमासशब्दयोः समासः क्रियते कालान्ते द्विगौ पूर्वपदप्रकृतिस्वरो यथा स्यात्। द्व्यहजात इत्यत्र च समासान्तः॥

(उद्द्योतः) भाष्ये—**परिमाणिनेति**। परिमाणिवाचकोत्तरपदेनेत्यर्थः। समासपदं च सामर्थ्यात्तत्पुरुषपरम्। एवं च तेन करणेन पूर्वयोर्द्विगुसिद्धये त्रयाणां तत्पुरुषो वक्तव्य इत्यर्थः॥ ननु द्विगोरन्येन समासाभावाद् द्विगोः समास इत्ययुक्तमत आह—**द्विगोरिति**॥ **निष्पत्तये** इति पाठः। निष्पत्ताविति पाठे निष्पादने कर्तव्य इत्यर्थः॥ तदुपपादयति—**द्वौ मासाविति**॥

(विग्रहान्तरेण विधानवैयर्थ्यभाष्यम्)

एवं तर्हि इदं स्यात्—द्वौ मासौ द्विमासं द्विमासं जातस्येति॥

(प्रदीपः) **द्वौ मासौ द्विमासमिति**। समाहारे द्विगुः। **पात्रादिभ्यः प्रतिषेध** इति स्त्रीत्वाभावः॥

(विग्रहान्तरदूषणभाष्यम्)

नैवं शक्यम्। स्वरे हि दोषः स्यात्। द्विमासजात इति प्राप्नोति। द्विमासजात इति चेष्यते॥

(प्रदीपः) **स्वरे हि दोष इति**। समासान्तोदात्तत्वेन जाताकार उदात्तः स्यादित्यर्थः॥

(दूषणान्तरभाष्यम्)

द्व्यहजातश्च न सिद्ध्यति। द्व्यहजात इति प्राप्नोति॥

(उद्द्योतः) भाष्ये—**द्व्यहजातश्चेति**। **न संख्यादेः समाहार** इति तत्र समासान्तनिषेधादिति भावः॥

(आक्षेपभाष्यम्)

न चैवं भवितव्यम्?॥

(समाधानभाष्यम्)

भवितव्यं च यदा समाहारे द्विगुः॥ द्व्यहजातस्तु नसिद्ध्यति॥

(आक्षेपभाष्यम्)

किमुच्यते परिमाणिनेति, नपुनरन्यत्रापि पञ्च गवप्रियः दश गवप्रियः?॥

(१२८४ विधानसाधकवार्तिकम् ॥ १० ॥)

॥ * ॥ अन्यत्र समुदायबहुव्रीहित्वादुत्तरपदप्रसिद्धिः ॥ * ॥

(व्याख्याभाष्यम्)

अन्यत्र समुदायो बहुव्रीहिसंज्ञः। अन्यत्र समुदायबहुव्रीहित्वादुत्तरपदं प्रसिद्धम्। उत्तरपदप्रसिद्धेः 'उत्तरपदे' इति द्विगुर्भविष्यति॥

(प्रदीपः) **अन्यत्रेति**। पञ्चगवधन इत्यादौ बहुव्रीहौ कृते पूर्वयोः समासान्तादिकार्यसिद्धये एकार्थीभावे प्रागपि सत्येव पुनः समासः क्रियते। एतेन पूर्वोक्त इतरेतराश्रयदोषोऽपि परिहृतः।

(उद्योतः) एकार्थीभावे प्रागपि सत्येवेति । बहुव्रीहिसमासकृतैकार्थीभावे सत्येव तत्पुरुषभाविपदमात्रयोः पृथगेकार्थीभावाभावेपि समासः क्रियत इत्यर्थः । न च पृथगेकार्थीभावाभावेपि वृत्तिश्चेदत्रोत्तरपदग्रहणं व्यर्थम्, अतिप्रसङ्गस्त्वनभिधानादेव त्वयेव मयापि वारणीय इति वाच्यम् । द्विगुसंज्ञार्थत्वात् । तत्फलं तु द्विमासप्रिय इत्यादौ कालान्तद्विगुत्वप्रयुक्तः पूर्वपदप्रकृतिस्वर इति दिक् ॥ एतेनेति । त्रिपदबहुव्रीहिसत्त्वेनेत्यर्थः । तदुक्तं भाष्ये—उत्तरपदं प्रसिद्धमिति ।

(१२८५ वार्तिकम् ॥ ११ ॥)

॥ * ॥ सर्वत्र मत्वर्थे प्रतिषेधः ॥ * ॥

(भाष्यम्) सर्वेषु पक्षेषु द्विगुसंज्ञायाः मत्वर्थे प्रतिषेधो वक्तव्यः ॥ किं प्रयोजनम् ? । पञ्चखट्वा दशखट्वा । "द्विगोः" इतीकारो मा भूत् । पञ्चगुर्दशगुः "गोरतद्धितलुकि" इति टज् मा भूदिति ॥ तद्धितार्थोत्तरपद० ॥ ५० ॥

(प्रदीपः) **सर्वत्रेति** । यद्यर्थशब्दः स्वार्थे यदि वाभिधेयवचनो ज्ञापकाच्च तद्धितोत्पत्तिः तदा मतुपस्तद्धितत्वात् तदर्थेऽयमेव समासः स्यान्न तु बहुव्रीहिः । अशेषत्वात् । तस्य तु चित्रग्वादिरवकाशः । तस्मान्मत्वर्थे प्रतिषेधो वक्तव्यः॥ **पञ्चखट्वेति** । पञ्च खट्वा यस्या विद्यन्त इति यदि द्विगुः स्यात्तदा **वावन्तः स्त्रियां भाष्यत** इति पक्षे **द्विगोरिति** ङीप् प्राप्नोति पक्षे च नपुंसकत्वम् ॥ **पञ्चगुरिति** । तत्पुरुषत्वे सति टच् प्राप्नोति ॥ नन्वस्मिन् समासे सति मतुपः श्रवणं प्रसज्येत । न च **द्विगोर्लुगिति** लुगस्ति, **प्राग्दीव्यत** इत्यधिकारात् ॥ एवं तर्हि दोषोपलक्षणं भाष्यम् । मतुपो लुग् वक्तव्य इति दोषः । तल्लुकि च ङीप्समासान्तौ प्रतिषेधादेव न भविष्यतः । पञ्च आढका यस्याः सा पञ्चाढकेत्यत्र तु ङीप् प्राप्नोति ॥ ५० ॥

(उद्योतः) **अशेषत्वादिति** । अनुक्तसमासः शेष इति भावः । त्रिकतः शेषे तु परत्वाद्बहुव्रीहिसिद्धिरिति बोध्यम् ॥ **एवं तर्हीति** । केचित्तु तद्धितार्थेऽभिधेय इत्यर्थः । तद्धितोत्पत्तिज्ञापकं सजातीयापेक्षत्वात्प्राग्दीव्यतीयविषयमेव । किं चैतत्पक्षैकवाक्यतया स्वार्थत्वेपि प्राप्तस्यानभिधानादनुत्पत्तिः स्यादिति सम्भावनायामपि लिङि तन्मूलकमेव **मतुप्सूत्रे** मत्वर्थे द्विगावन्यतद्धितवन्मतुरपि स्यादित्याशङ्क्य **द्विगोर्मत्वर्थतद्धितस्य प्रतिषेधो वक्तव्यो यदि तन्नास्ति सर्वत्र मत्वर्थे प्रतिषेध इति, सति तस्मिंस्तेनैव सिद्ध**मित्युक्तम् । प्रत्ययप्रतिषेधारम्भेपि ङीप्टचोर्व्यावृत्तये इदमावश्यकमिति तदाशयः । तद्वचनाभिप्रायेण चात्रैतयोरापादनमिति भाष्याशय इत्याहुः ॥ **त्यत्र तु ङीप् प्राप्नोतीति** । परिमाणान्तत्वादिति भावः ॥ **न तद्धितलुकीति** निषेधस्तु अपरिमाणान्तादिविषय इति तात्पर्यम् । पञ्चकुमारिरित्यादौ ङीपो लुक्प्राप्तिरपि बोध्या ॥ ५० ॥

(२५५ तत्पुरुषे द्विगुसंज्ञासूत्रम् ॥ २ । १ । ३ आ. २ सू.)

४०० संख्यापूर्वो द्विगुः ॥ २।१।५१ ॥

(अनन्तरयोगस्यैव संबन्धाधिकरणम्)

(आक्षेपभाष्यम्)

किमनन्तरे योगे यः संख्यापूर्वः स द्विगुसंज्ञः, आहोस्वित्पूर्वमात्रे? ॥

(प्रदीपः) **संख्यापू** ॥ ५१ ॥ इह कश्चिदवयवोपेक्ष्यते यत्रैतदुच्यते—**अनन्तरस्य विधिर्वा भवति प्रतिषेधो** वेति क्वचित्तु समुदायो यथा **नान्तःपाद**मिति पाठे संहिताधिकारविहितस्य सर्वस्य कार्यस्य निषेधः क्रियते ततः संदेहात् पृच्छति- **किमनन्तर इति** ॥ **पूर्वमात्र इति** । अत्र पक्षे समानाधिकरणसमासत्रिसूत्रीविहितस्तत्पुरुष एव गृह्यते । अन्यथा द्विमुनि व्याकरणस्येत्यव्ययीभावस्यापि द्विगुसंज्ञा स्यात् ततश्चे**गन्ते द्विगा**विति स्वरः प्रसज्येत ॥

(उद्योतः) संख्यापूर्वो ॥ ५१ ॥ ततः **संदेहादिति** । व्याप्तिन्यायानन्तर्यन्याययोर्द्वयोरपि शास्त्रे आश्रयणादिति भावः ॥

(विशेषजिज्ञासाभाष्यम्)

किं चातः? ॥

(विशेषप्रदर्शकभाष्यम्)

यदानन्तरयोगे । एकशाटीति "द्विगोः" इतीकारो न प्राप्नोति ॥

(प्रदीपः) **एकशाटीति** । एकः शाट इति पूर्वकालेति समासः । शाटशब्दश्चाकारान्तोस्ति तस्यैव कनि कृते शाटक इत्येवं रूपं संभवति ॥

(विशेषप्रदर्शकभाष्यम्)

अथ पूर्वमात्रे । एकभिक्षा । अत्रापि प्राप्नोति ॥

(प्रदीपः) **एकभिक्षेति** । भिक्षशब्दो घञन्तोस्ति । तथा च **भिक्षदं न प्रकाशये**दिति प्रयोगः । तत्रैको भिक्ष इति पूर्ववत् समासे कृते समासार्थस्य स्त्रीत्वोपजनाद् ङीप् प्रसज्येत । यथा जनानां पदं जनपद इति समासे कृते समासार्थस्य पुंस्त्वमेवमिहापि स्त्रीत्वमिति मन्यते ॥

(उद्योतः) **इहापि स्त्रीत्वमिति** । एकभिक्ष इति तु नेष्यत एवेति भावः ॥

(प्रथमपक्षाभ्युपगमभाष्यम्)

अस्त्वनन्तरे ॥

(आक्षेपभाष्यम्)

कथमेकशाटी ? ॥

(समाधानभाष्यम्)

ईकारान्तेन समासो भविष्यति—एका शाटी एकशाटी ॥

(प्रदीपः) ईकारान्तेनेति । शाटशब्दाज्जातिलक्षणे ङीपि कृत इति भावः ॥

(उद्द्योतः) ङीपि कृत इति । एकशाट इति त्विष्यत एवेति भावः ।

(समाधानबाधकभाष्यम्)

इह तर्ह्येकापूपी "द्विगोः"इतीकारो न प्राप्नोति ॥

(प्रदीपः) एकापूपीति । एकश्चासावपूपश्चेति पूर्ववत्समासः। अत्र द्विगुत्वे सत्यकारान्तोत्तरपदो द्विगुः स्त्रियां भाष्यत इति द्विगोरितीकारः सिध्यति नान्यथा । केवलश्चापूपशब्दः पुंसि वर्तत इति जातिलक्षणो ङीप् नास्ति ॥

(द्वितीयपक्षाभ्युपगमभाष्यम्)

अस्तु तर्हि पूर्वमात्रे ॥

(आक्षेपभाष्यम्)

कथमेकभिक्षा ? ॥

(समाधानभाष्यम्)

टाबन्तेन सह समासो भविष्यति—एका भिक्षा एकभिक्षा ।

(प्रदीपः) टाबन्तेनेति । भिक्षाशब्देन समासे कृते अत इत्यधिकाराद् ङीबभाव इत्यर्थः । भिक्षाशब्दश्च गुरोश्च हल इति स्त्रियां व्युत्पाद्यते । वाबन्त इत्यनेन पक्षे नपुंसकत्वं न भवति । व्यवस्थितविभाषाविज्ञानाद् ॥ यत्रापो ह्रस्वत्वं क्रियते पञ्चखट्वं पञ्चखट्वीत्यादौ तत्रैव वा क्लीबत्वं विधीयते । भिक्षाशब्देन त्वनभिधानात्समासो न भवतीति मन्यते । अन्यथा तत्रैकभिक्षीति स्यात् ॥

(उद्द्योतः) शाच्छोरिति सूत्रे परिगणितव्यवस्थितविभाषात्वस्यानुल्लेखादरुचेराह—यत्रापो ह्रस्वत्वमिति । स नपुंसकमिति प्रकरणात्समाहारद्विगुविषये एव तत्प्रवृत्तिरिति भावः ॥ ननु भिक्षाशब्देन समासे वक्ष्यमाणरीत्या समाहारविवक्षायां एकभिक्षीत्यपि स्यादत आह—भिक्षाशब्देन त्वनभिधानादिति । अत्र मर्म चिन्त्यम् ॥

(आक्षेपान्तरभाष्यम्)

इदं तर्हि—सप्तर्षयः 'इगन्ते द्विगौ' इत्येष स्वरः प्राप्नोति ॥

(प्रदीपः) सप्तर्षय इति । दिक्संख्ये संज्ञायामिति समासः ॥

(प्रथमपक्षाभ्युपगमभाष्यम्)

अस्तु तर्ह्यनन्तरे ॥

(आक्षेपभाष्यम्)

कथमेकापूपी ? ॥

(समाधानभाष्यम्)

समाहार इत्येव सिद्धम् ॥

(आक्षेपभाष्यम्)

कः पुनरत्र समाहारः ॥

(उद्द्योतः) कः पुनरिति । अनेकविषयत्वात् समाहारस्य एकस्य तदसंभवात् प्रश्नः ॥

(समाधानभाष्यम्)

यत्तद्दानं संभ्रमो वा ॥

(प्रदीपः) यत्तदिति । एकमप्यपूपं कश्चित् कृपणो ददद्नेकमिति मन्यते । दाने श्रद्धातिशयाद्वा महत्त्वाद्वा अनेकस्मिन्यः संभ्रमः स एकस्मिन्नपि कर्तव्यो भवति ॥

(उद्द्योतः) दददनेकमिति । अवयवगतबहुत्वस्यावयविन्यारोपात् गौणः समाहारोऽत्रापि सुलभ इति भावः ॥ कर्त्तव्यो भवतीति । एकापूपी क्रियत इत्यादौ प्रतिग्रहीत्रेति भावः ॥

(आक्षेपभाष्यम्)

इह तर्हि पञ्चहोतारो दशहोतारः । "इगन्ते द्विगौ" इत्येष स्वरो न प्राप्नोति ॥

(द्वितीयपक्षाभ्युपगमभाष्यम्)

अस्तु तर्हि—पूर्वमात्रे ॥

(आक्षेपभाष्यम्)

कथं सप्तर्षयः ? ॥

(समाधानभाष्यम्)

"*अन्तोदात्तप्रकरणे त्रिचक्रादीनां छन्दसि*" इत्येवमेतत्सिद्धम् ॥

(प्रथमपक्षाभ्युपगमभाष्यम्)

अथ वा पुनरस्तु—अनन्तरे ॥

(आक्षेपभाष्यम्)

कथं पञ्चहोतारः दशहोतारः ? ॥

(समाधानभाष्यम्)

***आद्युदात्तप्रकरणे दिवोदासादीनां छन्दसि* इत्येव सिद्धम् ॥ संख्यापूर्वो ॥ ५१ ॥**

(प्रदीपः) अथ वेति । पूर्वत्रापरितोषेणैतदुच्यते । भाषायामपि सप्तर्षिशब्दोऽन्तोदात्त इष्यते । प्रकृतिस्वरपूर्वपदश्च स्यात् । अत एवैकशाटीत्यादावपि द्विगुस्वराभावः ॥ ५१ ॥

(उद्द्योतः) पक्षद्वयेपि उपसंख्यानद्वयेन स्वरसिद्धेः साम्यशङ्कां वारयति—पूर्वत्रापरितोषेणेति । अन्तोदात्त इष्यते इति । अत्र बीजं चिन्त्यम् । किं च प्रवृद्धादिगणपाठेन लोकेप्यन्तोदात्तत्वं सुसाधमिति बोध्यम् ॥ प्रकृतिस्वरपूर्वपद इति बहुव्रीहिः ॥ केचित्तु पक्षयोः साम्येपि पूर्वमात्र इति पक्षस्य फलाभावाद्बहुप्रतिविधेयत्वाच्च नादर इत्याहुः ॥ ५१ ॥

(२५६ तत्पुरुषसंज्ञासूत्रम् ॥ २ । १ । ३ आ. ३ सू.)

४०१ कुत्सितानि कुत्सनैः ॥२।१।५२॥

(उदाहरणनिर्णयाधिकरणम्)

(आक्षेपभाष्यम्)

किमुदाहरणम् ? ॥

(समाधानभाष्यम्)

वैयाकरणखसूचिः ॥

(आक्षेपभाष्यम्)

किं व्याकरणं कुत्सितम्, आहोस्विद्वैयाकरणः?॥

(प्रदीपः) **कुत्सितानि** ॥ ५२ ॥ **किं व्याकरणमिति** । अयं भावः—शब्दप्रवृत्तिनिमित्तकुत्सायामयं समास इष्यते वैयाकरणश्चौर इत्यादौ मा भूदिति । तत्र व्याकरणस्य वेदाङ्गत्वान्नास्ति कुत्सा, नापि तदधीयानस्य ॥

(उद्द्योतः) कुत्सितानि ॥ ५२ ॥ इष्यत इति । तथैव लक्ष्यदर्शनात्प्रत्यासत्तेश्चेति भावः ॥ **चौर इति** । यथा खसूचनेन व्याकरणाध्ययनस्य निष्फलत्वं प्रतीयते न तथा चौर्येणेति भावः ॥ **नापि तदधीयानस्येति** । एवं च प्रवृत्तिनिमित्तकुत्साभावादिदं नोदाहरणमित्याशयेन भाष्ये किं **व्याकरणमित्यादि** प्रश्न इति भावः॥

(समाधानभाष्यम्)

वैयाकरणः कुत्सितः । तस्मिन्कुत्सिते तत्स्थमपि कुत्सितं भवति ॥ कुत्सितानि ॥ ५२ ॥

(प्रदीपः) **वैयाकरण इति** । यः पृष्टो निष्प्रतिभत्वात् खं सूचयति अहो गगनं निर्मलमिति प्रश्नं विस्मारयितुम्, स निष्फलव्याकरणाध्ययनत्वात् कुत्स्यते ॥ **तत्स्थमपीति** । आश्रयदोषादाश्रितस्यापि निष्फलत्वात् कुत्सा ॥ ५२ ॥

(उद्द्योतः) **आश्रयदोषादिति** । स चाप्रतिभत्वम् । अयं च निष्फलत्वे हेतुः ॥ ५२ ॥

(२५७ तत्पुरुषसंज्ञासूत्रम् ॥ २।१।३ आ. ४ सू.)

४०३ उपमानानि सामान्यवचनैः ॥ २ । १ । ५४ ॥

(उपमानोपमेयभावनिर्णयाधिकरणम्)

(आक्षेपभाष्यम्)

उपमानानीत्युच्यते कानि पुनरुपमानानि । किं यदेवोपमानं तदेवोपमेयम्,आहोस्विदन्यदेवोपमानमन्यदुपमेयम् ? ॥

(प्रदीपः) **उपमानानि** ॥ ५४ ॥ **कानीति** । सूत्रानुरोधेन बहुवचनं कृतम् ॥ **किं यदेवोपमानमिति** । अत्र तूपमानमात्रस्य जिज्ञासितत्वाद् बहुत्वविवक्षायाः प्रयोजनाभावादेकवचननिर्देशः ॥ ननु कर्मकरणयोर्भेदादेकत्वविषये संदेहाभावात् प्रश्नानुपपत्तिः ॥ अयं भावः—शस्त्रीश्यामा देवदत्तेति श्यामत्वं सर्वाश्रयव्यापि यद्यभिन्नं विवक्षितं तदा तद्द्वारेण शस्त्रीदेवदत्तयोरुपमानोपमेयत्वात्तस्य च तयोरविशिष्टत्वात् तद्द्वारकस्तयोरभेद इति यदेवोपमानं तदेवोपमेयमित्यभ्युपगतं भवति । न चैतद्युक्तम् । शस्त्रीशब्दप्रयोगवैयर्थ्यप्रसङ्गात् । अथाधारभेदात् श्यामत्वस्य भेदस्तदा शस्त्रीदेवतास्थयोः श्यामगुणयोर्भेदान्नास्ति तद्द्वारक उपमानोपमेयभावः—इति ॥

(उद्द्योतः) **उपमानानि** ॥ ५४ ॥ **उपमानत्वं** साधारणधर्महेतुकपरिच्छेदकरणत्वं तद्वति तस्य रूढत्वात् । तच्चोपमेयसाकाङ्क्षम् । तत्रोपमानोपमेयपदार्थयोरभेदो भेदो वा । रावण इव रावणः चन्द्र इव मुखमित्युभयत्रापि इवशब्ददर्शनात् ॥ तत्र यदि सर्वथाऽभेदे उपमानोपमेयभावस्तदा तत्र तद्गतभूयोधर्मपरिच्छेद्यत्वरूपोपमेयत्वासंभवः । अत एव सर्वथा भेदेपि नेत्याशयेन पृच्छति—भाष्ये—**कानि पुनरिति** । उपमेयात्सर्वथाऽभिन्नानि सर्वथा ।न्नानि वेत्यर्थः ॥ साधारणधर्मरूपेणाभेदस्तत्तद्रूपेण भेद इति त्वसौ न जानाति । तदेवाह—**किं यदेवेति** । **एव**कारेण तयोरत्यन्ताभेदः सूचितः । **एवमन्यदेवे**त्यनेनात्यन्तभेदः सूचितः । कर्मकरणरूपार्थभेदेपि द्वितीयसदृशव्यवच्छेदफलकस्य गौरिव **गौरिति** प्रयोगस्य दर्शनात्सर्वत्र तथैव किमिति प्रश्नः ॥ **क इहोपमार्थ** इति भाष्ये उपमानोपमेयक्षावबोधकेवादिशब्दप्रयोगे किं फलं कर्मकरणत्वरूपोपमानोपमेयत्वबोधस्यैकत्रासंभवादित्यर्थः ॥ द्वितीयोपमानव्यवच्छेदार्थत्वे तु नोपमानत्वादिव्यवहार । किंच **गोसदृशो** गौरित्यादिनैव तद्व्यवच्छेदबोधसंभवेऽनावाचकैतत्प्रयोगासंगतः सादृश्यस्याभेदेप्यङ्गीकारेण नास्यावाचकत्वमिति भावः ॥ उपमानोपमेयभावप्रतीतावुपमा, तदभावेनन्वय इति बोध्यम् ॥ अत्र पक्षेस्यैवोदाहरणत्वेन तत्र चोपमानत्वाद्यप्रतीत्या सर्वथेवादिघटितप्रयोगस्य बोधकस्य मुख्यस्यासंभव इति उपमोदाहरणासंभवः प्रकृतसूत्रवैयर्थ्यं चेति तात्पर्यम् ॥ **गौरिवाश्व इति** । अयं भावः—सर्वथा भेदे तत्स्वीकारे इदमुदाहरणं वाच्यम् तच्चायुक्तं साधारणधर्ममूलकोपमानोपमेयभावाप्रतीतेरिति केचित् ॥ **एकत्वविषये संदेहाभावा**दिति पाठे एकत्वरूपे विषये संदेहविषयत्वाभावादित्यर्थः ॥ **अयं भाव** इत्यादिग्रन्थेनोच्यमानो भावः कथं भाष्याक्षरस्वरससिद्धः । किं च शस्त्रीश्यामेत्यादौ शस्त्रीशब्दवैयर्थ्यस्योपमानोपमेयभावासंभवस्य च भाष्येनुक्तेस्तस्य निर्दलतेति बहुश्रुता विचारयन्तु ॥ **वैयर्थ्यप्रसङ्गादिति** । तेन कस्यचिद्विशेषस्यानभिधानादिति भावः ॥ श्यामत्वमात्रप्रतीतेः श्यामापदेनैवोपपत्तेः । एवं चोपमाप्रयोजकीभूतसाधारणधर्म आश्रयभेदेप्येक इति तयोरैक्यशङ्का, अनेक इति मते धर्मभेदात्तद्भेदशङ्केति तात्पर्यम् ॥

(प्रत्याक्षेपभाष्यम्)

किं चातः ? ॥

(प्रदीपः) **किंचात इति** । स्ववाचाभिप्रायमभिधापयितुं प्रश्नः ॥

(उद्द्योतः) **स्ववाचेति** । करणम् । **स्वशब्देन शङ्किता** । प्रयोजककर्त्ता तु प्रष्टा बोध्यः ॥

(प्रथमपक्षे आक्षेपभाष्यम्)

यदि यदेवोपमानं तदेवोपमेयम्, क इहोपमार्थः—गौरिव गौरिति ॥

(प्रदीपः) **गौरिवेति** । व्यक्तिगतानां भेदानां शब्देनासंस्पर्शात् सामान्यमुखेन द्रव्यावसायादिति भावः ॥

(उद्योतः) **शब्देनासंस्पर्शादिति** । कैयटकृतप्रश्नव्याख्याने अस्योपयोगश्चिन्त्यः साधारणधर्मस्य गोत्वस्यैक्येन गौरिवेत्यस्य वैयर्थ्यमिति तद्व्याख्यायां दोषोपपत्तेः । केचिद्व्याख्यानपूर्वपक्षे त्वत्रैवं व्याख्योचिता ॥

(द्वितीयपक्षे आक्षेपभाष्यम्)

अथान्यदेवोपमानमन्यदुपमेयम्, क इहोपमार्थः—गौरिवाश्व इति ॥

(प्रदीपः) **गौरिवाश्व इति** । अत्यन्तभेदविवक्षायामिदमुच्यते । यदा त्वश्वस्य जाड्यादिधर्मप्रतिपादनायेदमुच्यते तदा भवत्येवोपमानोपमेयभावः ॥

(उद्योत) **अत्यन्तेति** । अस्याशय उक्त एव ॥ **यदा त्विति** । इदमपि कैयटोक्तपूर्वपक्षव्याख्यायां चिन्त्यं श्यामत्ववज्जाड्यस्याप्येकत्वेनानेकत्वेन वा तदाप्युपमानोपमेयभावासंभवादिति ॥

(समाधानभाष्यम्)

एवं तर्हि यत्र किंचित्सामान्यं कश्चिच्च विशेषः तत्रोपमानोपमेये भवतः ॥

(प्रदीपः) **किंचित्सामान्यमिति** । श्यामत्वस्याधारभेदाद्भेदोप्याश्रीयते गुणजातेरेकत्वादभेदोपीत्यर्थः ॥

(उद्योतः) भाष्ये—**एवं तर्हि यत्र किंचिदिति** । शब्दोपात्तप्रत्येकधर्मेण शस्त्रीत्वदेवदत्तत्वादिना भेदः श्यामत्वादिसाधारणधर्मेण चाभेद इत्यर्थः ॥ ननु गुणानामाश्रयभेदाद्भेदेन कथं तेषां सामान्यत्वमित्यत आह—**श्यामत्वस्याधारेति** ॥ **भेदोप्याश्रीयते इति** । भेदो यद्यप्याश्रीयत इत्यर्थः ॥ तथापीति शेषः । **गुणजातेरिति** । गुणत्वव्याप्यजातेरित्यर्थः । एवं च श्यामगुणस्य भेदेपि श्यामत्वेनैक्यात्सामान्यत्वं साधारणधर्मतेति ध्वनितम् । अत्र सिद्धान्तपक्षे तु घन इव श्यामो देवदत्त इत्यादेरिवघटितप्रयोगस्य संभवेन गौरिव गौरित्यादावुपमानत्वाद्यप्रतीत्यानन्वय इति बोध्यम् ॥

(आक्षेपभाष्यम्)

किं वक्तव्यमेतत् ? ॥

(प्रदीपः) **किं वक्तव्यमिति** । यथोपवर्णितं वचनेन विना कथं प्रतिपत्तुं शक्यमिति भावः ॥

(समाधानभाष्यम्)

नहि ॥ कथमनुच्यमानं गंस्यते ? । मानं हि नामानिर्ज्ञातज्ञानार्थमुपादीयते–अनिर्ज्ञातमर्थं ज्ञास्यामीति । तत्समीपे यन्नात्यन्ताय मिमीते तदुपमानं गौरिव गवय इति । गौर्निर्ज्ञातः गवयोऽनिर्ज्ञातः ॥

(प्रदीपः) इतरो निर्वचनेन यथोक्तं प्रतिपादयितुमाह—**नहीति** ॥ **मानं हीति** । यथा प्रस्थादि । तेन हि साकल्येन मेयं परिच्छिद्यते ॥ **तत्समीप इति** । मानस्य समीप इत्यर्थः । परिच्छेदवशाच्च सामीप्यं परिकल्प्यते न त्वत्र मुख्यं सामीप्यमस्ति ॥ **उपमानानीति** निपातनात्तत्पुरुषः । अव्ययीभावे ह्येतद्रूपं न स्यात् ॥

(उद्योतः) भाष्ये—**मानं हीति** । अनिर्ज्ञातार्थस्य साकल्येन ज्ञापकत्वं हि तत्त्वम् । यथा प्रस्थाद्यज्ञातस्य परिमाणरूपार्थस्य साकल्येन ज्ञापकम्, न तथोपमानम् । गौर्हि गवयं कतिभिश्चिद्धर्मैरेव तद्गतैर्ज्ञापयति न साकल्येनेत्याशयेनाह—**साकल्येनेति** ॥ एवं च तदत्यन्ताभेदेनैव परिच्छेद्येनान्वेति—प्रस्थो व्रीहिरित्यादौ परिच्छेद्ये तद्रूपारोपात् । भेदेनैव वा प्रस्थोस्य परिमाणमित्यादौ । तदुक्तं भाष्ये—**'अत्यन्तायेति'** । इदमव्ययम् । आत्यन्तिकाभेदेनात्यन्तिकभेदेन वा तत्परिच्छिनत्ति । इदं तु भेदाभेदाभ्यामिति विशेषः ॥ चन्द्रेण तुल्यमित्यादावप्यार्थोपमाप्रतीतावस्त्येव भेदाभेदप्रतीतिरिति बोध्यम् ॥ **परिच्छेदवशादिति** । तत्तारतम्यादिति भावः ॥ अव्ययीभावे बहुवचनासंगतेराह—**निपातनादिति** । हीनार्थकोपशब्देन कर्मधारयस्य सुलभत्वम् । भाष्ये समीपशब्देन हीनत्वमेवोपलक्ष्यते । **उपोधिके चे**त्यादावुपस्य हीनार्थत्वदर्शनादित्यन्ये ॥

(आक्षेपभाष्यम्)

कामं तर्ह्यनेनैव हेतुना यस्य गवयो निर्ज्ञातः स्याद् गौरनिर्ज्ञातः, तेन कर्तव्यं स्याद्—गवय इव गौरिति ॥

(प्रदीपः) **कामं तर्हीति** । ततश्च व्यवस्था न प्राप्नोतीति भावः ॥

(इष्टापत्तिभाष्यम्)

बाढं कर्तव्यम् ॥

(प्रदीपः) **बाढमिति** । अपेक्षानिमित्तकः पितापुत्रादिव्यवहारवदुपमानोपमेयभाव इति न कश्चिद्दोष इत्यर्थः ॥

(उद्योतः) **अपेक्षानिमित्तक इति** । निरूपकापेक्षानिमित्तक इत्यर्थः ॥ **पितापुत्रादीति** । ज्ञानप्रदत्वाद्यत्र पुत्राणामपि पितृत्वव्यवहारस्तद्विषयोयं दृष्टान्तः॥ जातिस्मरत्वे जन्मान्तरविषयो वा॥

(उदाहरणनिर्णयाधिकरणम्)

(आक्षेपभाष्यम्)

किं पुनरिहोदाहरणम् ? ॥

(प्रदीपः) **किं पुनरिति** । अयं भावः—यदा शस्त्रीशब्दः शस्त्र्यामेव वर्तते श्यामाशब्दोपि तस्यामेव तदा समासेनोपमेयाया देवदत्ताया अभिधानं न प्राप्नोति । अथ श्यामा-

शब्दो देवदत्तायां वर्तते तदा वैयधिकरण्यात् समासाप्रसङ्गः। वचनसामर्थ्यात्समासे मृगीव चपला मृगचपलेति पुंवद्भावो न प्राप्नोति ॥

(उद्द्योतः) किं पुनरिति । अत्यन्तभेदाभेदयोरुपमानत्वाभावात्प्रश्नः। क्व पुनरिति प्रश्ने कैयटोक्तो भाव उचित इति केचित् ॥ न प्राप्नोतीति। उभयोरपि पदयोरेकार्थवृत्तित्वादिति भावः ॥ वैयधिकरण्यादिति। साहृश्यसंबन्धेन शस्त्र्याः श्यामावाच्यदेवदत्तायामन्वयेन सामर्थ्येपि वैयधिकरण्यमित्यर्थः। अत्र हि समानाधिकरणेनेति वर्तते। इदमुपलक्षणं सामान्यवचनत्वाभावाच्चेत्यपि बोध्यम् । समानविभक्तिकत्वमुपमानोपमेययोर्न स्यादित्यपि बोध्यम् ॥ पुंवद्भाव इति । सामानाधिकरण्यनिमित्तककर्मधारयत्वनिमित्तक इत्यर्थः ॥

(समाधानभाष्यम्)

शस्त्रीश्यामा ॥

(प्रदीपः) शस्त्रीश्यामेति । साधारणधर्मविशिष्टोपमेयार्थवृत्तिः शब्दः सामान्यवचनशब्देन वचनग्रहणाद् गृह्यते यथा गुणवचनशब्दो गुणोपसर्जनद्रव्यवाची ॥

(उद्द्योतः) साधारणधर्मविशिष्टेति। अनेन सामान्यवचनत्वं समर्थितमुपमेयदेवदत्ताभिधानं च। तस्यामेवोभयं वर्तत इति वक्ष्यमाणरीत्या च सामानाधिकरण्यम् ॥

(आक्षेपभाष्यम्)

क्व पुनरयं श्यामाशब्दो वर्तते? ॥

(प्रदीपः) क्व पुनरिति। उभयथा दोषदर्शनात् प्रश्नः॥

(उद्द्योतः) इदं तात्पर्यमजानानः पृच्छति—भाष्ये—क्व पुनरिति ॥

(एकदेशिसमाधानभाष्यम्)

शस्त्र्यामित्याह ॥

(उद्द्योतः) एकदेशिन उत्तरम्—शस्त्र्यामिति। समुदायेन तदभिधानोपपत्तेः ॥

(आक्षेपभाष्यम्)

केन तर्हीदानीं देवदत्ताऽभिधीयते ॥

(प्रदीपः) केनेति । पूर्वपदोत्तरपदयोरुपमानवृत्तित्वे तद्व्यतिरिक्तशब्दान्तराभावात् प्रश्नः ॥

(उद्द्योतः) केनेति प्रश्नानुपपत्तिमाशङ्क्याह—पूर्वपदेति। अवयवातिरिक्तसमुदाये मानाभाव इत्यर्थः ॥

(समाधानभाष्यम्)

समासेन ॥

(प्रदीपः) समासेनेति । स्वाभाविकत्वादर्थाभिधानस्यान्यपदार्थग्रहणमन्तरेणाप्यश्वकर्णादिवज्जातिविशेषस्य शस्त्रीश्यामादिकः समास उपमेयस्य वाचक इत्यर्थः ॥

(उद्द्योतः) नन्वन्यपदार्थग्रहणाभावात्कथं समासस्योपमेयवृत्तितेत्यत आह—स्वाभाविकत्वादिति । वस्तुतोतिरिक्तत्वाभावेपि बुद्धिकल्पितः कश्चित्सोस्त्येवेति भावः ॥ अश्वकर्णादिवज्जातिविशेषस्येति । अश्वकर्णादिर्यथा जातिविशेषस्येत्यर्थः ॥ अश्वकर्णादिर्जातिविशेषस्येवेति क्वचित्पाठः ॥

(आक्षेपभाष्यम्)

यद्येवं शस्त्रीश्यामो देवदत्त इति न सिद्ध्यति ॥

(प्रदीपः) यद्येवमिति । गुणवचनस्याश्रयलिङ्गानुविधायित्वात् स्त्रीलिङ्गेन श्यामाशब्देन समासे कृते रूपस्याप्रसिद्धिः ॥

(उद्द्योतः) स्त्रीलिङ्गेनेति । एतेन पुंलिङ्गश्यामशब्देन समासे रूपसिद्धिरिति नाशङ्क्यमिति भावः ॥

(समाधानभाष्यम्)

"उपसर्जनस्य" इति ह्रस्वत्वं भविष्यति ॥

(प्रदीपः) उपसर्जनस्येति । अप्राधान्यादुपसर्जनत्वं मन्यते। समासवाच्यत्वादुपमेयं हि प्रधानम् ॥

(आक्षेपभाष्यम्)

यदि तर्ह्युपसर्जनान्यप्येवंजातीयकानि भवन्ति, तित्तिरिकल्माषी कुम्भकपाललोहिनी—अनुपसर्जनलक्षण ईकारो न प्राप्नोति ॥

(प्रदीपः) यदि तर्हीति । ह्रस्वविधौ कृत्रिममेवोपसर्जनं गृह्यते न तु लौकिकमपि कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसंप्रत्यय इति न्यायाल्लौकिकग्रहणे दोषप्रसङ्गाच्च। तित्तिरिकल्माषी कुम्भकपाललोहिनीत्यत्रोपमानस्य पुन्नपुंसकलिङ्गत्वात्समासात् प्राक् स्त्रीप्रत्ययो नास्ति। समासे कृतेऽनुपसर्जनाधिकाराद् ङीप्ङीषोः प्रतिषेधः प्राप्नोति। सत्यपि वा ङीषि सति शिष्टत्वादुपमानस्वरं बाधित्वा ङीप्स्वरः प्राप्नोति॥

(उद्द्योतः) कृत्रिममेवेति । लौकिकसमानाधिकरणमिति बोध्यम्। सामान्यवचनैरित्यप्रथमानिर्दिष्टत्वात् श्यामाशब्दो न तथेति भावः ॥ नतु लौकिकमपीति । केवललौकिकमित्यर्थः ॥ दोषप्रसङ्गादिति। आचारक्यजन्तप्रकृतिककुमारीशब्दादौ ह्रस्वप्रसङ्गादित्यर्थः ॥ पुंनपुंसकेति । तित्तिरिः पुमान्, कुम्भकपालं क्लीवम्॥ स्त्रीप्रत्ययो नास्तीति। तत्समानाधिकरणकल्माषलोहितयोरप्यस्त्रीत्वादिति भावः ॥ ङीब्ङीषोः। अन्यतो ङीप् वर्णादनुदात्तादिति विहितयोः॥ सत्यपि वेति। वर्णादनुदात्तादित्यादौ अनुपसर्जनत्वस्य तदन्तविशेषणत्वात्समासोत्तरमिति भावः। अत एव श्येण्या च शलल्येत्यादिसिद्धिः ॥ उपमानस्वरः। पूर्वपदप्रकृतिस्वरः। ङीप्स्वरोऽन्तोदात्तः । एवं च तित्तिरिकल्माषीत्यत्रैव दोष इति भावः ॥ भाष्यस्य तु नात्र स्वरसः॥ श्येण्येत्यादि त्वार्षम् ॥

(समाधानभाष्यम्)

एवं तर्हि शस्त्र्यामेव शस्त्रीशब्दो वर्तते, देवदत्तायां श्यामाशब्दः ॥

(प्रदीपः) **एवं तर्हीति** । ततः पूर्वोक्तदोषाभावः । शस्त्रीश्यामो देवदत्त इति श्यामशब्दस्य देवदत्तवृत्तित्वात् तित्तिरिकल्माषीति स्त्रीप्रत्ययान्तेनोपमेयवृत्तिना समासविधानात् ॥

(आक्षेपभाष्यम्)

एवमपि गुणो न निर्दिष्टो भवति । बहवः शस्त्र्यां गुणाः—तीक्ष्णा सूक्ष्मा पृथुरिति ॥

(प्रदीपः) **एवमपीति** । श्यामाशब्दस्य देवदत्ताभिधाने चरितार्थत्वाच्छस्त्रीगतो गुणो न निर्दिष्टः स्यादित्यनियतगुणनिमित्तसादृश्यप्रतीतिप्रसङ्ग इत्यर्थः ॥

(उद्योतः) ननु श्यामाशब्दस्य श्यामत्वगुणेनैव देवदत्ताद्यभिधायकत्वात्कथं गुणानिर्देश इत्यत आह—**शस्त्रीगतो गुण इति** । सादृश्यमतिरिक्तः पदार्थ इति मतेनेदं, एवं च श्यामाशब्दस्य सामान्यवचनत्वाभाव इत्यपि बोध्यम् ॥ **अनियतगुणनिमित्तेति** । संसर्गविधया प्रतीयमानसादृश्येत्यर्थः ॥

(समाधानभाष्यम्)

अनिर्दिश्यमानस्यापि गुणस्य भवति लोके संप्रत्ययः । तद्यथा—'चन्द्रमुखी देवदत्ता' इति बहवश्चन्द्रे गुणाः, या चासौ प्रियदर्शनता सा गम्यते ॥

(प्रदीपः) **चन्द्रमुखीति** । अयं भावः—यत्रानिर्दिष्टोपि गुणो वृद्धव्यवहारवशादुपमानिमित्तत्वेन प्रतीयते तत्रोपमेये श्रुतः सन्निधानादुपमानं कथं न स्प्रक्ष्यति ॥

(उद्योतः) उपमानिमित्तत्वेनेति पाठः । **उपमाननिमित्तत्वेनेति** पाठे उपमानत्वप्रतीतिनिमित्तत्वेनेत्यर्थः ॥ **कथं न स्प्रक्ष्यतीति** । उपस्थितत्वेन प्रत्यासत्त्या चेत्यर्थः । एवं च भाष्याब्धिः क्वातिगम्भीर इत्यत्र मयूरव्यंसकादिसमास एव । उक्तरीत्या सामान्यप्रयोगसत्त्वेनोपमितसमासाप्राप्तेः ॥ चन्द्रमुखीत्यत्र बहुव्रीहौ स्वाङ्गाच्चोपसर्जनादिति ङीष् ॥

(आक्षेपभाष्यम्)

एवमपि 'समानाधिकरणेन' इति वर्तते । व्यधिकरणत्वात्समासो न प्राप्नोति ॥

(प्रत्याक्षेपेण समाधानभाष्यम्)

किं हि वचनान्न भवति ? ॥

(प्रदीपः) **किं हि वचनादिति** । दुर्बलं प्रकरणं श्रुत्या बाध्यत इत्यर्थः ॥

(समाधानबाधकभाष्यम्)

तावद्वचनात्समासः स्यात् । इह खलु मृगीव चपला मृगचपला समानाधिकरणलक्षणः पुंवद्भावो न प्राप्नोति ॥

(प्रदीपः) **पुंवद्भाव इति** । **पुंवत्कर्मधारयजातीयदेशीयेष्वित्यनेन** ॥ नन्वस्त्रीपूर्वपदस्य विवक्षितत्वात् मृगक्षीरादिवन्मृगचपलेति भविष्यति । यद्यप्यन्यत् स्त्रियाश्चापत्यमन्यत् पुंसस्तथापि पुंवद्भावेन स्त्रीप्रत्यये निवृत्ते नास्ति स्त्रीत्वलक्षणविशेषावगतिः । प्रकरणादिवशात्तु स्त्रीत्वप्रतिपत्तौ जातिमात्रोपादानेपि तत्प्रतीतिर्भविष्यति । सा च बहिरङ्गत्वात् स्त्रीप्रत्ययोत्पत्तिनिमित्तं न भवति ॥ एवं तर्हि प्रतिपत्तिगौरवप्रसङ्गादेतदत्र भाष्यकारेण नाश्रितम् गत्यन्तरसंभवाच्च ॥

(उद्योतः) भाष्ये—**समानाधिकरणलक्षण** इति । पूर्वपदार्थस्य सादृश्यसंबन्धेनोत्तरपदार्थेन्वयेन व्यधिकरणत्वादिति भावः ॥ **पुंवत्कर्मधारयेति** । एतेन चपलशब्दस्य प्रियादित्वान्मृगीशब्दस्य जातिशब्दत्वाच्च कथमत्र पुंवत्त्वमित्यपास्तम् ॥ **अस्त्रीपूर्वपदस्येति** । जातिमात्रविवक्षायां मृगशब्देन समास इति भावः ॥ **बहिरङ्गत्वादिति** । प्रकरणादिसापेक्षप्रतीतिकत्वेन तत्त्वम् । मृगीव चपलेति विग्रहे त्वव्यविकन्यायाद्वाक्यमेवेति भावः ॥

(सिद्धान्तिसमाधानभाष्यम्)

एवं तर्हि तस्यामेवोभयं वर्तते । एतच्चात्र युक्तं यत्तस्यामेवोभयं वर्तेत इति । इतरथा हि बह्वपेक्ष्यं स्यात् ॥

(प्रदीपः) तद्दर्शयति—**एवं तर्हीति** । शस्त्रीसादृश्याद्देवदत्ता शस्त्रीशब्देनोच्यते सादृश्यनिमित्तादभेदोपचाराद् यथा गौर्वाहीक इति । पूर्वावस्थाश्रयेण च शङ्कया उपमानवाचित्वमवसेयम् ॥

(उद्योतः) ननु शस्त्रीशब्दस्य कथं देवदत्तायां वृत्तिरत आह—**सादृश्यादिति** ॥ तद्व्याचष्टे—**सादृश्यनिमित्तादिति** । तत्प्रयोजकसाधारणधर्मरूपान्निमित्तादित्यर्थः । परिच्छेदकश्यामशस्त्र्यभिन्ना परिच्छेद्या श्यामा देवदत्तेति बोधः । एतच्च मञ्जूषायां विस्तरेण प्रपञ्चितम् ॥ **पूर्वावस्थेति** । यद्यपि पुंवत्त्वानुरोधाद्वाक्येपि अभेदान्वय आवश्यको वृत्तौ वृत्तेः प्राक् च यत्र सामानाधिकरण्यं तत्रैव पुंवत्त्वप्रवृत्तेस्तथापि यदा केवलस्य प्रयोगस्तदा तद्वचनत्वमित्यभिमानः ॥ परे तु **उपमानानीत्यस्य** तत्त्वेन बोधकानीत्यर्थः । इवशब्दसमभिव्याहाराच्च वाक्ये तत्त्वेन बोधकता, वृत्तौ तु समासशक्तिबलादित्युपमानवाचित्वाभावशङ्कैव निर्दला, इवशब्दश्च स्वसमभिव्याहृते उपमानत्वद्योतकः । शस्त्रीपदस्य तत्सदृशपरत्वमिवो द्योतयतीति तु न युक्तं, द्योत्यार्थे समभिव्याहृतपदार्थविशेषणताया एव स्वभावसिद्धत्वात् । अत एव णिच्तरबादीनां द्योतकतापक्षस्य प्रकृत्यर्थविशेषणतेति शब्देनोल्लेखो भाष्य इत्याहुः ॥

(समाधानभाष्यशेषभाष्यम्)

यदि तावदेवं विग्रहः करिष्यते-शस्त्रीव श्यामा देवदत्तेति। शस्त्र्यां श्यामेत्येतदपेक्ष्यं स्यात्॥

(प्रदीपः) **यदि तावदिति**। यदा श्यामाशब्दो देवदत्तायां वर्तते शस्त्रीशब्दः शस्त्र्यामेव तदा शस्त्रीगतं श्यामत्वमनेकगुणसंभवे गुणान्तरव्यवच्छेदायोपमानिमित्तं प्रतिपादयितुं श्यामेत्यपेक्षणीयम्॥

(उद्द्योतः) उपमानिमित्तमिति। उपमा सादृश्यं तन्निमित्तं शस्त्रीगतं देवदत्तागतं वा श्यामत्वं प्रतिपादयितुं तत्तद्गतत्वेन बोधयितुमित्यर्थः। उभयत्र श्यामत्वप्रकारकबोधस्तत्र न स्यादिति भावः। इदं च दशमे लिङ्गभेदादिरूपोपमादूषणप्रस्तावे काव्यप्रकाशतट्टीकादौ स्पष्टम्। उपमानतावच्छेदकारोपेणाभेदान्वयादेवोपमानोपमेययोः समानविभक्तित्वनियमः॥ [अपेक्ष्यं स्यादितिभाष्यस्य तत्त्वेन बोधार्थमित्येवार्थः॥]

(समाधानभाष्यशेषभाष्यम्)

अथाप्येवं विग्रहः करिष्यते—यथा शस्त्री श्यामा तद्वदियं देवदत्तेति। एवमपि देवदत्तायां श्यामेत्येतदपेक्ष्यं स्यात्॥

(प्रदीपः) **अथापीति**। यदा शस्त्र्यामेव शस्त्रीशब्दो वर्तते श्यामाशब्दोपि तस्यामेव, तदा देवदत्तागतश्यामत्वप्रतिपादनाय श्यामेत्यपेक्षणीयम्। न च शब्दस्यावृत्तिरस्ति येनोभयगतं श्यामत्वं प्रतिपादयेत्॥

(आक्षेपभाष्यम्)

एवमपि गुणो न निर्दिष्टो भवति। बहवश्च शस्त्र्यां गुणाः तीक्ष्णा सूक्ष्मा पृथुरिति॥

(प्रदीपः) अत्रापि दोषमाह—**एवमपीति**। यदा शस्त्रीसादृश्याद्देवदत्तायां शस्त्रीत्वमारोप्यते तदा कं गुणमाश्रित्य सादृश्यमाश्रीयतामित्यर्थः॥

(उद्द्योतः) **तस्यामेवेति** सिद्धान्तपक्षेपि शङ्कते—**एवमपीति**भाष्ये। शस्त्र्यां श्यामगुणानिर्देशादिति भावः। तदाह—**कं गुणमिति**। शस्त्र्यां तीक्ष्णत्वादिबहुगुणसत्त्वादिति भावः॥

(समाधानभाष्यम्)

अनिर्दिश्यमानस्यापि गुणस्य भवति लोके संप्रत्ययः। तद्यथा—चन्द्रमुखी देवदत्तेति बहवश्चन्द्रे गुणाः। या चासौ प्रियदर्शनता सा गम्यते॥

(प्रदीपः) उत्तरं तु पूर्वमेव व्याख्यातम्। यद्यपि पूर्वयोरपि पक्षयोरेष परिहारोस्ति तथापि ह्रस्वस्त्रीप्रत्ययस्वरपुंवद्भावासिद्ध्या पूर्वं पक्षद्वयं परिहृत्यायं पक्ष आश्रितः॥

(उद्द्योतः) उत्तरयति—**अनिर्दिश्यमानस्यापीति**। यत्रानिर्देशेपि बहुगुणवति वस्तुनि तात्पर्यवशाद्यः कश्चिदेव गुणः प्रतीयते तत्रोपमेये श्रुतस्यश्यामादिना कथमुपमानं न संभन्त्स्यत इति भावः। तद् ध्वनयन्नवक्ष्यति—श्यामाशब्दः शस्त्रीशब्देनाभिसंबध्यमानो विशेष्यवचन इत्यादि॥ **एष परिहार इति**। इतरथा हि बह्वपेक्षं स्यादित्युक्तदोषस्येत्यर्थः॥ पुंवद्भावासिद्धेति। उभयस्य श्यामत्वप्रकारकबोधासिद्धेत्यपि बोध्यम्॥

(१३२० वार्तिकम्॥ १॥)

॥ * ॥ उपमानसमासे गुणवचनस्य विशेषभाक्त्वात्सामान्यवचनाप्रसिद्धिः॥ * ॥

(व्याख्याभाष्यम्)

उपमानसमासे गुणवचनस्य विशेषभाक्त्वात् सामान्यवचनस्याप्रसिद्धिः स्यात्—शस्त्रीश्यामेति। श्यामाशब्दोयं शस्त्रीशब्देनाभिसंबध्यमानो विशेष्यवचनः संपद्यते। तत्र सामान्यवचनैरिति समासो न प्राप्नोति॥

(प्रदीपः) **उपमानसमास इति**। शस्त्रीश्यामा देवदत्तेत्यत्र शस्त्रीशब्दसन्निधौ श्यामाशब्दः प्रयुज्यमानः शस्त्रीगतं श्यामत्वगुणं प्रतिपादयति, न च शस्त्रीस्थो गुण आश्रयान्तरे वर्तत इति सामान्यवचनत्वाभाव इत्यर्थः॥

(उद्द्योतः) पदार्थद्वयगतश्यामत्वोक्तावपि सामान्यवचनत्वहानिरिति शङ्कते—भाष्ये—**उपमानसमास इति**॥ न च **शस्त्रीस्थ** इत्युपलक्षणं उपमानोपमेयस्थ इत्यर्थः। भाष्ये **शस्त्रीशब्देने**त्यप्युपलक्षणमुपमेयेन चेत्यस्यापि॥

(१३२१ वार्तिकम्॥ २॥)

॥ * ॥ न वा श्यामत्वस्योभयत्र भावात्तद्वाचकत्वाच्च शब्दस्य सामान्यवचनत्वस्य प्रसिद्धिः॥ * ॥

(व्याख्याभाष्यम्)

न वा एष दोषः॥ किं कारणम्?॥ श्यामत्वस्योभयत्र भावात्। उभयत्रैवात्र श्यामत्वमस्ति शस्त्र्यां देवदत्तायां च। तद्वाचकत्वाच्च शब्दस्य। तद्वाचकश्चात्र श्यामाशब्दः प्रयुज्यते॥ किंवाचकः?। उभयवाचकः। श्यामत्वस्योभयत्र भावात् तद्वाचकत्वाच्च शब्दस्य सामान्यवचनत्वं प्रसिद्धम्। सामान्यवचने प्रसिद्धे सामान्यवचनैरिति समासो भविष्यति॥ नावश्यं स एव सामान्यवचनः यो बहूनां सामान्यमाह, द्वयोरपि यः सामान्यमाह सोपि सामान्यवचन एव॥ अथ वा सामान्यवचनैरित्युच्यते। सर्वश्च शब्दोन्येन

शब्देनाभिसंबध्यमानो विशेषवचनः संपद्यते। त एवं विज्ञास्यामः—प्रागभिसंबन्धाद्यः सामान्यवचन इति ॥ उपमानानि ॥ ५४ ॥

(प्रदीपः) **नवेति** । शस्त्रीशब्दोपादानसामर्थ्यात् श्यामगुणसन्निधानाच्च यादृशं शस्त्रीश्यामत्वमन्यविलक्षणं तादृशं देवदत्ताया इति संप्रत्ययाद् उभयसाधारणं श्यामत्वं भवति सामान्यमिति न कश्चिद्दोषः। तत्र सादृश्यं सामान्यमुच्यते गुणो वा द्विवृत्तिर्भिन्नोप्यभिन्नत्वेन विवक्षितः सामान्यम् ॥ **सर्वश्चेति** । शब्दान्तरसंबन्धे सर्वः शब्दो विशेषवाचित्वात्सामान्यवचनो न भवतीति सामान्यवचनग्रहणोपादानसामर्थ्याच्छब्दान्तराभिसंबन्धात्समासरूपात् प्राग्यः शब्दः सामान्यवचनः स गृह्यते केवलश्च श्यामाशब्दः श्यामगुणविशिष्टं स्त्रीत्वयुक्तं द्रव्यमात्रमाहेति सांप्रतिकाभावे भूतपूर्वगत्याश्रयणात्सिद्धमिष्टम् ॥ ५४ ॥

(उद्योतः) **शस्त्रीशब्दोपादानेति** । **उपमानशब्दोपादानेति** क्वचित्पाठः। अयमेव युक्तः। अयं भावः—शस्त्र्यादीनामुपमानत्वेनोपादानात् उपमेयसापेक्षत्वेन श्यामशब्द उपमेयायां वर्त्तते तस्य च तत्रैणोपमानेष्यन्वयः। एवं चोभयवृत्तिगुणवाचकत्वेन तस्य सामान्यवचनत्वमिति भावः ॥ नन्वेवमपि तयोर्गुणयोराश्रयभेदाद्भेदेन सामान्यस्योभयवृत्त्येकधर्मस्य न वाचकमेतदत आह—**यादृशमिति** । सादृश्यमूलकाभेदाध्यवसायेन सामान्यवचनतेति भावः ॥ **सादृश्यमिति** । सादृश्यमूलकाभेदमापन्नं श्यामत्वमित्यर्थः ॥ **गुणो वेति** । क्रियादेरप्युपलक्षणमेतत् ॥ **अभिन्नत्वेन विवक्षित इति** । श्लेषमूलकाभेदाध्यवसानादित्यर्थः ॥ **अभेदेने**ति क्वचित्पाठः ॥ भाष्येऽप्युभयवाचक इत्यनेन श्लेषमूलकमभेदाध्यवसानमुभयत्रान्वयश्च दर्शितः। अन्यथा वाचकताया वस्तुतोऽनेकश्यामगुणनिरूपितायाः सत्त्वेन **न चावश्य**मित्यादिग्रन्थो ऽसङ्गत एव स्यात् ॥ अथ बहुगतसामान्यवचनस्यैव ग्रहणेपि न क्षतिरित्याह—**अथ वेति** । अत एवाद्यपक्षयोः श्यामापदस्य सामान्यवचनत्वनिर्वाहः ॥ **सामान्यवचनग्रहणेति** । सामान्यवचनपदेत्यर्थः ॥ **समासरूपादिति** । इदमुपलक्षणं वाक्यस्यापीति दिक् ॥ ५४ ॥

(२५८ तत्पुरुषसंज्ञासूत्रम् ॥ २ । १ । ३ आ. ५ सू.)

४०४ उपमितं व्याघ्रादिभिः सामान्याप्रयोगे ॥२।१।५५॥

(सामान्याप्रयोगप्रयोजनाधिकरणम्)

(आक्षेपभाष्यम्)

सामान्याप्रयोग इति किमर्थम् ? ॥

(समाधानभाष्यम्)

इह मा भूत्—पुरुषोयं व्याघ्र इव शूरः, पुरुषोयं व्याघ्र इव बलवान् ॥

(प्रदीपः) **उपमितम् ॥ ५५ ॥ पुरुषोयं व्याघ्र इव शूर इति** । उपमानप्रतिपादनपरमेतत्। वैयधिकरण्यादेवात्र समासस्याप्रसङ्गः। यदा तु व्याघ्रशब्दः शौर्यादेः पुरुषार्थ एव वर्तते तदा सामानाधिकरण्ये सति समासेन भाव्यम्। तत्र यदा प्रकरणादिवशान्नियतसाधारणगुणप्रतिपत्तिस्तदा सामान्याप्रयोगे सति समासः। यदा तु गुणान्तरव्यवच्छेदाय विशिष्टसाधारणगुणवचनशब्दप्रयोगः पुरुषो व्याघ्र इव शूर इति तदा समासाभावाय सामान्याप्रयोगग्रहणम् ॥

(उद्योतः) उपमितम् ॥ ५५ ॥ **उपमानप्रतिपादनेति** । उपमानत्वप्रतिपादनेत्यर्थः ॥ **एतत्** । इवघटितं वाक्यम् ॥ **वैयधिकरण्यादेवेति** । व्याघ्रस्यैवार्थसादृश्ये संबन्धेनान्वय इत्यभिमानः ॥ **यदा त्विति** । वाक्येपीति भावः। इवशब्दस्तु तद्गतोपमानत्वद्योतक इति बोध्यम्। इदमेव युक्तं पूर्वसूत्रोक्तभाष्यस्वरसात् समानविभक्तित्वनियमाच्च ॥ **साधारणगुणवचनेति** । **भाव्याब्धिः क्वातिगम्भीर** इत्यादौ तु मयूरव्यंसकादित्वात्समासः ॥

(प्रत्याख्यानभाष्यम्)

सामान्याप्रयोग इति शक्यमवक्तुम् ॥

(आक्षेपभाष्यम्)

इह कस्मान्न भवति—पुरुषोयं व्याघ्र इव शूरः, पुरुषोयं व्याघ्र इव बलवान् ? ॥

(समाधानभाष्यम्)

असामर्थ्यात् ॥ कथमसामर्थ्यम् ? । सापेक्षमसमर्थं भवतीति ॥ एवं तर्हि सिद्धे सति यत् "सामान्याप्रयोगे" इति प्रतिषेधं शास्ति, तज्ज्ञापयत्याचार्यो 'भवति वै प्रधानस्य सापेक्षस्यापि समासः' इति ॥ किमेतस्य ज्ञापने प्रयोजनम् ? । राजपुरुषोभिरूपः राजपुरुषो दर्शनीयः । अत्र वृत्तिः सिद्धा भवति ॥ उपमितम् ॥ ५५ ॥

(प्रदीपः) **भवति वै प्रधानस्येति** । न्यायसिद्ध एवार्थे लिङ्गदर्शनमिदम् । प्राधान्यादेवानेकोपकारकोपकार्यत्वाविरोधात्समासस्य सिद्धत्वात् ॥ ५५ ॥

(उद्योतः) भाष्ये—**भवति वै प्रधानस्यापीति** । न च पूर्वसूत्रस्थभाष्यरीत्या व्याघ्रेणापि शूरपदार्थान्वयाद्विशेषणमप्यत्र सापेक्षं यथा व्याघ्रः शूर एवं पुरुष इति प्रतीतेः। अत एवोपमानोपमेययोर्लिङ्गभेदादेर्दोषत्वम्, अन्यतरलिङ्गस्य साधारणधर्मस्योभाभ्यां भिन्नलिङ्गाभ्यामन्वयायोग्यत्वं हि तद्बीजमिति वाच्यम्। उपमानत्वेन बोधकस्य तस्य साधारणधर्मांशे नित्यसापेक्षत्वेनादोषात्। साधारणधर्मवत्त्वेनेतरपरिच्छेदकत्वं हि तत्त्वम्। तच्च तत्त्वेन ज्ञातस्यैव ॥ यद्यपि साधारणधर्मवत्त्वेन परिच्छेद्यत्वमेवोपमेयत्वमित्युपमेयमपि नित्यसापेक्षम् ॥ इदमपि तत्रैव सूत्रे भाष्ये ध्वनितम् ॥ तथापि ज्ञापकपरं भाष्यमेकदेश्युक्तिः ॥ प्रधानस्य सापेक्षस्य वृत्तिस्तु कैयटोक्तन्यायादेव ॥ **असामर्थ्या**दित्यस्योभयोरर्पातरसापेक्षत्वेनासामर्थ्यादित्यर्थः। शस्त्रीश्यामेत्यादौ पूर्वोत्तरपदयोः परस्परापे-

क्षत्वं नासामर्थ्यप्रयोजकमिति न दोषः ॥ यद्यपि लिङ्गवचनभेदेप्य-भेदान्वयो वेदाः प्रमाणमित्यादौ दृष्टस्तथापि लिङ्गभेदादीनां दूषकताबीजं सहृदयोद्वेग एवेति स्पष्टमलंकारतत्त्वविदाम् ॥ अने-कोपकारकोपकार्यत्वं, अनेकविशेषणविशेष्यत्वम् ॥ ५५ ॥

(२५९ तत्पुरुषसंज्ञासूत्रम् ॥ २।१।३ आ. ६ सू.)

४०५ विशेषणं विशेष्येण बहुलम् ॥२।१।५६॥

(विशेषणस्योपसर्जनत्वाधिकरणम्)

(१३२२ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ विशेषणविशेष्ययोरुभयविशेषणत्वादुभयविशेष्यत्वादुपसर्जनाप्रसिद्धिः ॥ * ॥

(व्याख्याभाष्यम्)

विशेषणविशेष्ययोरुभयविशेषणत्वादुभयोश्च विशेष्यत्वादुपसर्जनत्वस्याप्रसिद्धिः । कृष्णतिला इति कृष्णशब्दोयं तिलशब्देनाभिसंबध्यमानो विशेषणवचनः संपद्यते, तथा तिलशब्दः कृष्णशब्देनाभिसंबध्यमानो विशेषणवचनः संपद्यते, तदुभयं विशेषणं भवत्युभयं च विशेष्यम् । विशेषणविशेष्ययोरुभयविशेषणत्वादुभयोश्च विशेष्यत्वादुपसर्जनत्वस्याप्रसिद्धिः ॥

(प्रदीपः) **विशेषणम् ॥ ५६ ॥ विशेषणविशेष्ययोरिति ।** उभयापेक्षेयं षष्ठी ॥ नित्यसापेक्षत्वाच्चोभयशब्दस्य शब्दान्तरेण समासो भवति । विशेषणविशेष्याभिमतयोर्द्वयोर्द्वैरूप्यसद्भावात् समाससिद्धावप्यनियतः पूर्वनिपातः प्राप्नोतीति दोषः ॥ **कृष्णशब्द इति ।** कृष्णशब्द उच्चरितो भ्रमरकोकिलादिद्रव्यमात्रं प्रतिपादयति । तिलशब्देन त्वभिसंबध्यमानस्तिलेष्वेव नियम्यते इति कृष्णशब्दो विशेष्यस्तिलशब्दो विशेषणम् । एवं तिलशब्दस्यापि विशेष्यत्वं कृष्णशब्दस्य च विशेषणत्वमवसेयम् ॥

(उद्द्योतः) **विशेषणं वि० ॥५६॥** भाष्ये—**उभयविशेषणत्वादिति ।** उभयोर्विशेषणत्वादित्यर्थः ॥ कयोरुभयोः, ? विशेषणविशेष्ययोः, अत्रोभयमुद्दिश्य विशेषणत्वस्य विधेयताप्रतीतेः समासेनोद्देश्यविधेयभावः ॥ ननु विशेषणविशेष्ययोरिति षष्ठी नोपसर्जनाप्रसिद्धिरित्यपेक्षया विशेषणे उपसर्जनत्वप्रसिद्धिसत्त्वात् नाप्युभयापेक्षया सविशेषणतया समासानापत्तेरत आह—**उभयापेक्षेयमित्यादि ॥** ननु विशेषणविशेष्ययोरुभयं चेद्विशेषणं विशेष्यं च तदोभयोरप्युपसर्जनत्वादुपसर्जनाप्रसिद्धिरिति दूषणासङ्गतिरत आह—**अनियत इति ।** व्यावर्त्यव्यावर्तकभाव एव विशेषणविशेष्यभावः स च परस्परमुभयोरित्यव्यवस्थेति शङ्कार्थ इति भावः ॥ उपसर्जनाप्रसिद्धिरित्यस्योपसर्जननियमासिद्धिरित्यर्थो भाष्ये ॥ द्रव्यमात्रम् । कृष्णगुणं सर्वं द्रव्यम् ॥ **तिलशब्दो विशेषण-मिति ।** परिच्छेदकबोधक इत्यर्थः । परिच्छेद्यपरिच्छेदकभाव एव न विशेष्यविशेषणभाव इत्यभिमानः ॥

(१३२३ समाधानवार्तिकम् ॥ २ ॥)

॥ * ॥ नवान्यतरस्य प्रधानभावात्तद्विशेषकत्वाच्चापरस्योपसर्जनप्रसिद्धिः ॥ * ॥

(व्याख्याभाष्यम्)

नवा एष दोषः ॥ किं कारणम् ? । अन्यतरस्य प्रधानभावात् । अन्यतरदत्र प्रधानम् ॥ तद्विशेषकत्वाच्चापरस्य । तद्विशेषकं चापरम् । अन्यतरस्य प्रधानभावात्तद्विशेषकत्वाच्चापरस्योपसर्जनसंज्ञा भविष्यति यदाऽस्य तिलाः प्राधान्येन विवक्षिता भवन्ति कृष्णो विशेषकत्वेन, तदा तिलाः प्रधानं कृष्णो विशेषणम् ॥

(प्रदीपः) **नवेति । अन्यतरस्य** द्रव्यस्यैवेत्यर्थः ॥ **अपरस्येति ।** गुणस्यैवेत्यर्थः ॥ **यदाऽस्य तिला इति ।** ते हि द्रव्यरूपत्वात् क्रियासिद्धये साक्षादुपयुज्यमाना प्राधान्येन विवक्ष्यन्ते । कृष्णस्तु गुणत्वात् द्रव्यव्यवधानेन क्रियायामुपयोगाद्विशेषणं तिलानां संपद्यते ॥

(उद्द्योतः) अन्यतरापरशब्दयोः सर्वप्रतिपादकत्वादनियमस्तदवस्थ इत्यत आह—**द्रव्यस्यैवेत्यर्थ इत्यादि ।** द्रव्यस्यैवानयनादिक्रियासंभवेन तस्यैव क्रियान्वयौचित्येन तस्यैव विषयताविशेषरूपं विशेष्यत्वमिति भावः ॥ एतदेव ध्वनयितुं **प्रधानपदं** भाष्ये उपात्तम् । तदेव चात्र विशेष्यविशेषणभावशब्देन गृह्यते न तु परिच्छेद्यपरिच्छेदकभाव इति तत्त्वम् ॥ एतदेव ध्वनयन्नाह—**ते हीति ।** यदातदाशब्दौ भाष्ये यतस्तत इत्यर्थकाविति भावः ॥ प्राधान्येनेत्यस्य तेनैवेत्यर्थः ॥

(आक्षेपभाष्यम्)

कामं तर्ह्यनेनैव हेतुना यस्य कृष्णाः प्राधान्येन विवक्षिता भवन्ति तिला विशेषणत्वेन, तेन कर्तव्यं तिलकृष्णा इति ॥

(प्रदीपः) इतरो यथोक्तं न्यायमबुद्ध्वा विवक्षामात्रनिबन्धनत्वमनेन विशेषणविशेष्यभावस्य प्रतिपादितं विवक्षायाश्च

स्वातन्त्र्यादनियमात् प्रयोगानियम इति मन्यमानः पृच्छति—**कामं तर्हीति** ॥

(उद्द्योतः) **विवक्षामात्रेति** । यदातदाशब्दौ विवक्षिता [इ]तिशब्दश्च भाष्यस्थोऽबोधे विपरीतप्रतिपत्तौ च बीजम् ॥ **विशेषणविशेष्यभावस्येति** । परिच्छेदकपरिच्छेद्यभावस्येत्यर्थः । **प्रतिपादितमित्यस्य** 'इति च बुद्ध्वा' इति शेषः ॥ **स्वातन्त्र्यादिति** । प्रयोक्तुरिति शेषः ॥

(समाधानभाष्यम्)

न कर्तव्यम् । नह्ययं द्वन्द्वः—तिलाश्च कृष्णाश्चेति । न खल्वपि षष्ठीसमासः—तिलानां कृष्णा इति । किं तर्हि ? । द्वाविमौ प्रधानशब्दौ एकस्मिन्नर्थे युगपदवरुध्येते । न च द्वयोः प्रधानशब्दयोरेकस्मिन्नर्थे युगपदवरुध्यमानयोः किंचिदपि प्रयोजनमस्ति, तत्र प्रयोगादेतद्गन्तव्यम्—नूनमत्रान्यतरत्प्रधानं तद्विशेषकं चापरमिति । तत्र त्वेतावान् संदेहः—किं प्रधानं किं विशेषणमिति । स चापि क्व संदेहः यत्रोभौ गुणशब्दौ । तद्यथा—खञ्जकुब्जः कुब्जखञ्ज इति । यत्र ह्यन्यतरद् द्रव्यमन्यतरो गुणः, तत्र यद् द्रव्यं तत्प्रधानम् । तद्यथा—'शुक्लमालभेत' 'कृष्णमालभेत' न पिष्टपिण्डीमालभ्य कृती भवति । अवश्यं तद्गुणं द्रव्यमाकाङ्क्षति ॥

(प्रदीपः) **नह्ययमिति** । नहि गुणद्रव्यवाचिनोर्द्वन्द्व उपपद्यते । गुणवचनस्य द्रव्यापेक्षत्वादसामर्थ्याद्द्रव्येण सहविवक्षाया असंभवात् । यदि तु द्वन्द्वः स्यात्स्यादेव तिलकृष्णा इति प्रयोगः ॥ **न खल्वपीति** । गुणेन सह षष्ठीसमासनिषेधादिति भावः ॥ **प्रधानशब्दाविति** । प्रथमान्तावित्यर्थः । अनेन षष्ठीसमासविपरीतत्वं कथितम् ॥ **एकस्मिन्नर्थे** इत्यनेन तु द्वन्द्वविपरीतत्वं कथितम् । द्वन्द्वे हि सर्वपदार्थानां प्राधान्यादस्ति सर्वपदानामेकस्मिन्नर्थेऽवस्थानम् । एतच्चावयवार्थापेक्षयोक्तम् । समुदायार्थापेक्षायां तु समुदायलक्षण एकस्मिन्नर्थे सर्वेषां पदार्थानां वृत्तिरस्त्येव ॥ **प्रधानशब्दयोरिति** । परस्परविशेषणत्वेनानुपकारकयोः स्वतन्त्रयोरित्यर्थः ॥ **यत्रोभाविति** । द्वयोरपि गुणत्वाद् द्रव्यव्यवधानेन क्रियासाधनत्वाविशेषादिति भावः ॥ **यत्र ह्यन्यतरद् द्रव्यमिति** । तत्र नास्ति संदेह इति वाक्यशेषः ॥ **यद् द्रव्यमिति** । साक्षात् क्रियासाधनत्वादिति भावः ॥ ननु तिलशब्दो जातिवाची न द्रव्यवाची । तत्र जातिविशिष्टद्रव्यवाचित्वाद्यदि द्रव्यवाचीत्युच्यते तदा कृष्णशब्दोपि गुणविशिष्टद्रव्यवाचित्वाद् द्रव्यवचन आपद्यत इति नानयोः कश्चिद्विशेषः ॥ नैष दोषः । उत्पत्तिप्रभृत्याविनाशाज्जातिर्द्रव्यं न जहाति । न च शब्देन द्रव्याद्व्यतिरेको जातेः प्रत्याय्यते । नहि भवति 'शाबलेयस्य गौः' इति । किं तर्हि ? 'गौः शाबलेयः' इति । तस्माज्जात्यात्मकमेव द्रव्यं प्रतीयत इति जातिशब्दो द्रव्यवचनत्वेनावस्थाप्यते । गुणाः पुनरुपायिनश्चापायिनश्च पटस्य शुक्ल इति व्यतिरिक्ता अपि द्रव्यात् स्वशब्देन गुणाः प्रत्याय्यन्त इति गुणात्मकत्वं द्रव्यस्य नास्तीति न गुणशब्दो द्रव्यवचनत्वेनावस्थापनमर्हति । एतन्न्यायाश्रयेण वैदिकव्यवहारं निदर्शनायोपन्यस्यति—**तद्यथेति** । **श्वेतं छागमालभेतेति** चोदनायां श्वेताभावे कृष्णच्छाग आलभ्यते छागाभावे तु शुक्लस्य द्रव्यान्तरस्यालम्भो नास्ति ॥

(उद्द्योतः) **द्रव्येण सहविवक्षाया इति** । साक्षाद् द्रव्यवत्क्रियायामनन्वयादिति भावः ॥ **यदि त्विति** । ननु सोस्तीति, न तथाप्रयोग इति भावः ॥ भाष्ये विपरीतविशेषणविशेष्यभावविवक्षैव नेति नानेन समासे तथाप्रयोगः समासान्तरेणापि नेत्युक्तम् ॥ भाष्ये—**तिलानां कृष्णा इति** । कृष्णा अवयवा इत्यर्थः ॥ **निषेधादिति** । एवं चैतदुत्तरं **तिलकृष्णा** इति भाष्ये क्वचिद् दृश्यमानो ऽपाठ इति बोध्यम् । एवं च न द्वन्द्वषष्ठीसमासार्थावितः प्रतीयेते नापि तत्र साधुत्वं किं त्वभेदः प्रतीयते तत्रापि न साधुत्वमिति सर्वथा तद्रूपाभाव एवेति भाष्यार्थः ॥ पूर्वध्वनितं विपरीतविशेषणविशेष्यभावासंभवं स्फुटयति—**किं तर्हीत्यादिना** ॥ द्रव्यस्यैव प्राधान्याङ्गीकारात्प्रधानशब्दावित्यसंगतमित्याशङ्क्याह—**प्रथमान्ताविति** । तत्र वाक्यार्थे यन्मुख्यविशेष्यं तदभिन्नार्थकत्वाद् द्वितीयप्रथमान्तमपि प्रधानत्वेनोक्तमित्यर्थः । इदं प्रथमान्तेन विग्रह इति पक्षे । परिनिष्ठितविभक्त्या समास इति पक्षे समानविभक्त्यन्तावित्यर्थः । तद् ध्वनयन्नाह—**अनेनेति** ॥ **एकार्थेति** । विग्रहवाक्याभिप्रायेणेत्यर्थः । समासे तु द्वन्द्वेपि एकार्थीभावसत्त्वादुभयोरेकार्थवृत्तित्वमस्त्येवेत्याह—**समुदायार्थापेक्षायामिति** ॥ भाष्ये—**युगपदुपरुध्येते** । प्रयुज्येते ॥ **परस्परेति** । प्रथमान्तयोरिति शेषः ॥ भाष्ये—**यत्रोभौ गुणशब्दाविति** । क्रियाया अपि उपलक्षणमेतत् । अत एव खञ्जकुब्जावित्यत्र खञ्जेत्यस्य क्रियात्वेपि न क्षतिरित्याहुः ॥ **कुब्जवामन** इति केवलगुणोदाहरणं तत्प्रधानविशेष्यताद्वयविषयतावदित्यर्थः ॥ **न च शब्देनेति** । जातिप्रवृत्तिनिमित्तकेनेत्यर्थः ॥ शब्देन जातेर्द्रव्यव्यतिरेकाप्रतीतौ हेतुरुत्पत्तिप्रभृत्याविनाशमत्यागः तथा गुणानां व्यतिरेकप्रतीतौ हेतुरुपायित्वापायित्वम् । उपायापायावुत्पत्तिविनाशौ द्रव्ये सत्येव ॥ भाष्ये—**अवश्यं तद्गुणं द्रव्यमाकाङ्क्षतीति** । संनिहितपदोपात्तं छागादीति शेषः । तद्गुणकं द्रव्यविशेषमवश्यमपेक्ष्यते तदभावे गुणमात्रेण शास्त्रार्थसिद्धिं न मन्यते इति द्रव्यं प्रधानमित्यर्थः ॥ भाष्यस्थवाक्यमपि छा[गघ]टितमेवेत्याशयेनाह—**श्वेतच्छागमिति** । एवं चामुकदीक्षितः देवदत्तसोमयाजीत्यादयो लोके प्रयुज्यमाना अप्यसाधव इति बोध्यम् । एवं च कृष्णोपक्रमेपि वाक्ये

विशेष्यभूता एव तिलाः कृष्णगुणमाश्रयान्तरेभ्यो निवर्त्तयन्तीति न तिलानां परिच्छेदकत्वहानिः ॥ एतेन विशेषणताख्यविषयता-वदेव परिच्छेदकं भेदकं चेत्यपास्तम् ॥ राजपुरुष इत्यादौ च विशे-ष्यस्यापि पुरुषस्य राज्ञि भेदकत्वदर्शनादिति दिक् ॥

(आक्षेपभाष्यम्)

कथं तर्हीमौ द्वौ प्रधानशब्दावेकस्मिन्नर्थे युगप-दवरुध्येते—वृक्षः शिंशपेति ? ॥

(प्रदीपः) **कथं तर्हीति** । द्वयोरपि जातिशब्दत्वाद् द्रव्यवाचित्वात् प्रधानत्वान्नास्त्यन्यतरस्य विशेषणत्वमिति प्रश्नः॥

(उद्द्योतः) शिंशपावृक्षयोरपि सामान्यविशेषवाचित्वेन विशे-ष्यविशेषणभावमाशङ्क्याह—**द्वयोरिति** ॥ **नास्त्यन्यतरस्येति** । वृक्षस्येत्यर्थः ॥

(समाधानभाष्यम्)

नैतयोरावश्यकः समावेशः । नह्यवृक्षः शिंशा-पास्ति ॥ विशेषणम् ॥ ५६ ॥

(प्रदीपः) **नैतयोरिति** । आवश्यकमस्मिन्नस्तीत्यर्श-आदित्वादच्प्रत्ययः ॥ अयं भावः—यदा प्रथमत एव विशेष उपक्रम्यते शिंशपेति तदा वृक्षविशेषस्यैव प्रकान्तत्वाद्विशेषस्य च सामान्याव्यभिचाराद् वृक्षशब्दस्य नैव प्रयोगेण भाव्यम् । यदा तु प्रथमं सामान्यमुपक्रम्यते वृक्ष इति तदा तद्विशेषणाय शिंशपाशब्द उपादीयमानो विशेषणमेव भवतीति शिंशपावृक्ष इत्येव भाव्यम् ॥ अत्र केचिदाहुः—शिंशपाया अपि फल-व्यवच्छेदायोपादीयमानो वृक्षः किमिति विशेषणं न भवति ततश्च भवितव्यं वृक्षशिंशपेत्यपीति ॥ तदयुक्तम् । वृक्षत्वस्य व्यापकत्वान्महाविषयत्वाद् दूरात्प्रथमतस्तस्यैवोपलम्भाद्विशेष्य-त्वमेव । शिंशपात्वं तु स्वल्पविषयत्वात् पश्चाद् ग्रहणाच्च शुक्लादिगुणकल्पत्वाद्विशेषणमेवेति नास्ति प्रयोगस्यानियमः । तथा च वृक्षविशेषस्य खदिरादेः प्रतिनिधिर्भवति न तु वृक्ष-त्वाभावे फलपुष्पादेरुपादानं क्रियत इति न्यायविद आहुः ॥ **नह्यवृक्ष इति** । ननु फलमस्त्येव ॥ नैतदस्ति । वृक्षप्रतीति-व्यवधानेन फलप्रतीतेरुपादानाद्बहिरङ्गत्वाद्वृक्षावसायस्य प्रागुपा-दादन्तरङ्गत्वात् ॥ **विशेषणं विशेष्येणेति** द्वयोरुपादानं विरूपार्थम् । संबन्धिशब्दत्वादेवान्यतरेणेतरस्याक्षेपात् ॥ बहुलग्रहणाच्च तक्षकः सर्पो लोहितस्तक्षक इत्यादौ समा-साभावः ॥ ५६ ॥

(उद्द्योतः) भाष्ये **आवश्यक** इत्यस्य नियत इत्यर्थः ॥ कादाचित्कस्तु अस्त्येवेति भावः ॥ तदेवोपपादयति—**यदा प्रथ-मत एवेति** ॥ **यदा तु प्रथममिति** । अनेन च न केवलं गुण-द्रव्यसमभिव्याहारे द्रव्यस्य प्राधान्यमित्येव नियमः । किं तु व्याप्य-व्यापकजातिसमभिव्याहारे व्यापकस्य विशेष्यत्वमित्यपीति बोध्यते । वृक्षप्राधान्ये हेतुद्वयं प्रथमत उपलम्भादिति महाविषयत्वादिति च, महाविषयत्वमेवोपपादयति—**व्यापकत्वादिति** ॥ **विशेष्यत्व-मेवेति** । विषयताविशेषरूपमित्यर्थः । फलव्यवच्छेदाय वृक्षशब्द इत्यपि नेत्याह—**तथा चेति** ॥ वृक्षविशेषस्य खदिरादेः प्रतिनि-धिर्वृक्षो भवति, नतु तद्वृक्षाभावे तदीयफलाद्युपादानमित्यन्वयः । **वृक्षविशेषः खदिरादेरिति** पाठः पाठः । **वृक्षाभावे फलेत्यादिश्च** । एवं च फलं न वृक्षसमतया तदर्थ इति तात्पर्यम् ॥ तदाह— भाष्ये—**नह्यवृक्ष इति** । तथा च शिंशपोपक्रमे वृक्षपदप्रयोगो नेति भावः । अशिंशपा तु वृक्षोऽस्त्येवेति वृक्षोपक्रमे भवत्येव शिंश-पाप्रयोग इति बोध्यम् ॥ **वृक्षप्रतीतिव्यवधानेनेति** । एतेन लुब्योगाप्रख्यानादितिसूत्रस्वरसेन शिंशपादिशब्दानामपि फले मुख्यतया शिंशपात्वं वृक्षत्वव्यभिचारीति **नह्यवृक्ष** इति भाष्यम-संगतमित्यपास्तम् । लुपः प्रत्याख्यानेपि वृक्षसंबन्धित्वेनैव तद्बो-धात् । आदौ हि शिंशपाशब्दाद् वृक्षस्यैव प्रतीतिः । पश्चात्तत्सं-बन्धित्वेन फलस्येत्याशयात् ॥ नन्वन्तरङ्गत्वेपि फलार्थकत्ववारणाय वृक्षपदप्रयोगो भविष्यति तत्र च द्रव्यवाचित्वेन विशेष्यत्वानियमा-त्प्रयोगानियमो भविष्यत्येवेति चेन्न । **नह्यवृक्षः शिंशपा** प्रसिद्धास्तीति भाष्यार्थात् । एवं च फलरूपार्थस्याप्रसिद्धत्वादिना प्रकरणादिकं तदुपस्थित्यनुदयेन तद्व्यावर्त्तकविशेषणोपादानाभाव इति तात्पर्यात् । एवं च सामान्यविशेषवाचकपदसमभिव्याहारे सामान्यवाचकस्यैव विशेष्यत्वम् । यत्र तूभयोरपि परस्परापेक्षया सामान्यत्वं विशेषत्वं च तत्रानियम एव यथा ब्राह्मणदेवदत्तो देवदत्तब्राह्मण इति ॥ ननु विशेषणविशेष्ययोः सम्बन्धिकत्वादन्यतरोपादानेनैव सिद्धे उभयो-पादानं द्वयोरपि परस्परव्यभिचारित्व एव यथा स्यादित्येतदर्थम् । अत एव तक्षकः सर्प इत्यादौ न तक्षकत्वस्य सर्पत्वव्यभिचाराभा-वात् । ध्वनितं चेदं वृत्तौ ॥ तत्कथं शिंशपावृक्षे समास इत्यत आह—**द्वयोरुपादानमिति** । भाष्यप्रामाण्यात्स्वपदार्थमेव तदित्यर्थः । **तक्षको** नागवर्धक्योरिति कोशात् तक्षकत्वस्यापि सर्पत्वव्यभि-चाराच्च ॥ **बहुलग्रहणाच्च तक्षकः सर्प इति** । अत्र समासा-भावे प्रमाणं विचार्यं भाष्यारूढं यद्युश्रुतैः ॥ ५६ ॥

(२६० तत्पुरुषसमाससंज्ञासूत्रम् ॥ २ । १ । ३ आ. ७ सू.)

४०६ पूर्वापरप्रथमचरमजघन्यसमा-नमध्यमध्यमवीराश्च ॥२।१।५७॥

(एतदादिसूत्रप्रयोजनाधिकरणम्)

(आक्षेपभाष्यम्)

अथ किमर्थमुत्तरत्रैवमाद्यनुक्रमणं क्रियते, न "विशेषणं विशेष्येण बहुलम्" इत्येव सिद्धम् ॥

(प्रदीपः) **पूर्वा ॥ ५७ ॥ अथ किमर्थमिति** । एत-त्सूत्रादुत्तरसूत्रानुक्रमणमित्यर्थः ॥ **पूर्वकालेत्ययं तु** योगः पूर्वकालादीनां पूर्वनिपातनियमार्थः ॥ **दिक्संख्ये** इति

संज्ञायां नियमार्थः ॥ **कुत्सितानीति** विशेष्यस्य पूर्वनिपातार्थः । एवमन्यत्रापि प्रयोजनमूह्यम् । यत्र तु प्रयोजनाभावः **पूर्वापरप्रथमे**त्यादौ तस्यायमाक्षेपः पूर्वेणैव समासस्य सिद्धत्वात् ॥

(उद्द्योतः) **पूर्वापर** ॥५७ ॥ भाष्ये—**उत्तरत्र । विशेषणं विशेष्येणे**त्युत्तरम् ॥ **एवमादि पूर्वापरे**त्यादि ॥ तदाह—**एतस्माच्चोत्तरे**त्यादि ॥ उत्तरत्रेत्यस्य फलमाह—**पूर्वकाले**त्ययं स्विति ॥ **कृत्स्नमिति । दिक्संख्ये** इति नियमात् **तद्धितार्थे**त्यावश्यकम् । स्वार्थघटितेर्थे समासस्य शक्त्ये **उपमानानीति** । सामान्यवचनैरेवेति नियमार्थमिदमित्यन्ये ॥ **उपमितमिति** विशेष्यस्य पूर्वनिपातार्थमिति बोध्यम् ॥ **यत्र तु प्रयोजनाभाव इति** । वीरैकादिव्यावृत्तये बहुलग्रहणानुवृत्तेरत्राप्यावश्यकत्वेन तेनैव गुणादिसमभिव्याहारे पूर्वनिपातनियमसिद्धिरिति भावः ॥ भाष्ये **एवमादी**त्यादिशब्दः प्रकारे इति बोध्यम् ॥

(१३२४ समाधानवार्तिकम् ॥ १ ॥)

॥ * ॥ बहुलवचनस्याकृत्स्नत्वादुत्तरत्रानुक्रमणसामर्थ्यम् ॥ * ॥

(व्याख्याभाष्यम्)

अकृत्स्नं बहुलवचनमित्युत्तरत्रानुक्रमणं क्रियते ॥

(प्रदीपः) **बहुलवचनस्याकृत्स्नत्वादिति** । अकृत्स्नप्रतिपत्तृविषयत्वादित्यर्थः । नहि मन्दबुद्धयो बहुलग्रहणमात्रेण समासासमासविषयविवेकमवगन्तुं क्षमा इत्यर्थः ॥

(उद्द्योतः) **उत्तरत्रानुक्रमणसामर्थ्यमिति** । उत्तरत्रेत्याद्यनुक्रमणकरणसामर्थ्यमित्यर्थः । सूत्रकृता दर्शितमिति शेषः ॥

(आक्षेपभाष्यम्)

यद्यकृत्स्नं यदनेन कृतमकृतं तत् ॥

(प्रदीपः) इतरो यथोक्तमकृत्स्नशब्दार्थमप्रतिपद्य बहुलवचनस्याव्यापकत्वमकृत्स्नत्वं मत्वा चोदयति—**यद्यकृत्स्नमिति** । ततश्च निष्प्रयोजनं बहुलवचनमिति भावः ॥

(उद्द्योतः) **अव्यापकत्वमिति** । कृत्स्नपदं कृत्स्नविषयपरमिति भावः ॥ भाष्ये—**यदनेन कृतमिति** । प्रवृत्त्यप्रवृत्त्यादिकं तत्सर्वं विषयाव्यापकत्वान्निष्प्रयोजनमित्यर्थः ॥

(समाधानभाष्यम्)

एवं तर्हि न ब्रूमोऽकृत्स्नमिति, कृत्स्नं च कारकं च साधकं च निर्वर्तकं च यच्चानेन कृतं सुकृतं तत् ॥

(प्रदीपः) **कृत्स्नंचेति** । पर्यायोपादानं लौकिक्या वाचोयुक्त्या सामर्थ्याविघातप्रतिपादनार्थं यथा स्वामी प्रभुरीश्वरो भगवानिति ॥ चतुर्भिः शब्दैश्चत्वारो बहुलशब्दार्था इति क्वचित् प्रवृत्तिः क्वचिदप्रवृत्तिरित्यादयः संगृहीता इत्येक आहुः ॥ तेन कृष्णसर्प इत्यादौ नित्यः समासः । रामो जामदग्न्य इत्यादावसमासः । नीलमुत्पलं नीलोत्पलमित्यादौ विकल्पः । सुसूक्ष्मजटकेशादाववयवसमासाभावः ॥ **अन्ये** त्वाहुः—**कृत्स्नमिति** सर्वेष्टस्य संग्राहकत्वाद्व्यापकमित्यर्थः ॥ केन रूपेण व्यापकत्वमित्याह—**कारकमिति** ॥ कुर्वदपि न विपर्ययेण करोतीत्याह—**साधकमिति** । न च कस्यचिद्व्यं जनेन प्रवर्तकमित्याह—**निर्वर्तकमिति** ॥ अथ वा साधकं पारम्पर्येण स्यात् । वर्णोपदेश इव प्रत्याहारद्वारेण लक्ष्यसंस्कारस्येत्याह—**निर्वर्तकमिति** । साक्षात्कार्यं निष्पादयतीत्यर्थः ॥

(उद्द्योतः) **सामर्थ्याविघातेति** । बहुलग्रहणप्रतिवचनस्य प्रशंसार्थमित्यर्थः । तत्प्रयोजनं शङ्किनृसंतोषः । तेन तदाग्रहशान्तौ व्यर्थकालक्षेपाभावात्तत्र दृष्टान्तमाह—**यथेति** ॥ व्याख्यान्तरमाह—**चतुर्भिरिति** । चत्वारः, क्वचित्प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद्विभाषा क्वचिदन्यदेवेत्येवंरूपाः ॥ अत्र पक्षे कृत्स्नादिशब्दैः शब्दमर्यादयैतदर्थालाभादरुचेराह—**अन्ये त्विति** ॥**कारकमितीति** । प्रवृत्त्यादिकारकत्वेन व्यापकमित्यर्थः ॥ **साधकमितीति** । यथायोग्यकारकमित्यर्थः ॥ **निर्वर्तकं** भवंविषयात्यागेन साक्षात्प्रयोगसाधकमित्यर्थः ॥

(आक्षेपभाष्यम्)

किमर्थं तर्ह्येवमाद्यनुक्रमणं क्रियते? ॥

(समाधानभाष्यम्)

उदाहरणभूयस्त्वात् । एते खल्वपि विधयः सुपरिगृहीता भवन्ति येषु लक्षणं प्रपञ्चश्च । केवलं लक्षणं केवलः प्रपञ्चो वा, न तथा कारकं भवति ॥ अवश्यं खल्वप्यस्माभिरिदं वक्तव्यम्—बहुलम्, अन्यतरस्याम्, उभयथा, वा, एकेषामिति । सर्ववेदपारिषदं हीदं शास्त्रम् । तत्र नैकः पन्थाः शक्य आस्थातुम् ॥ पूर्वापर ॥ ५७ ॥

(प्रदीपः) **उदाहरणभूयस्त्वादिति** । **विभाषागुणेऽस्त्रियामि**ति पञ्चमी । अस्यैव लक्षणस्य भूयांस्युदाहरणानि प्रदर्शयितुमित्यर्थः ॥ **केवलमिति** । केवलेन लक्षणेन मन्दबुद्धिर्विषयविभागं नावधारयति । केवलेन प्रपञ्चेन च सामान्यलक्षणरहितेन प्रतिपदपाठवच्छास्त्रस्य गौरवप्रसङ्गः ॥ व्यवस्थितविभाषैव कस्मान्नाश्रीयते किं बहुलग्रहणेनेत्याह—**अवश्यमिति** । वैदिकव्यवहारानुसरणाय सर्वैः शब्दैरिह व्यवहार इत्यर्थः ॥ **सर्ववेदपारिषदमिति** । परिषद इदं पारिषदं साधारणमित्यर्थः । **पञ्चाध्वर्युपरिषदश्चे**त्यण् ॥ अन्येत्वाहुः—पारिषदः परिषत्परिचारक उच्यते । स च परिषत्साधारण इति पारिषदत्वेन साधारणत्वं लक्ष्यते । सर्ववेदाश्रत्वादस्य सर्ववेदसाधारणं लक्षणं बहुलादिग्रहणोपेतं क्रियते । आनुषङ्गिको लौकिकशब्दसंस्कार इति वेदग्रहणं कृतम् ॥ ५७॥

(उद्द्योतः) विभाषा गुणेति । प्रयोजनस्यापि प्रयोजकत्वेन हेतुत्वादिति भावः ॥ भाष्ये—**ते खल्वपीति** । यद्विधिविषये **लक्षणं** सामान्यशास्त्रं **प्रपञ्चस्तस्यैव** विशेषशास्त्रेण उदाहरणप्रदर्शनं ते विषयो मन्दामन्दबुद्धिभिः सर्वैरपि सम्यक् ज्ञातुं शक्यत्वात्**सुपरिगृहीता** भवन्तीत्यर्थः । एवं च प्रपञ्चार्थमिदं शास्त्रमिति भावः ॥ **केवलेनेति** । उदाहरणप्रपञ्चपरविशेषसूत्ररहितेन बहुलपदघटितसामान्यसूत्रेणेत्यर्थः ॥ **प्रपञ्चेनेति** । सामान्यलक्षणरहितप्रपञ्चपरविशेषसूत्रेणेत्यर्थः ॥ भाष्ये—**अवश्यं खल्वपीति** । अवश्यं विकल्पार्थकशब्दप्रयोगे कर्त्तव्ये पर्यायेषु लाघवगौरवविचाराभावात् । वेदे नानाशब्दैर्व्यवहारदर्शनाच्च वेदाङ्गत्वमस्यैवेति ध्वनयितुं वेदव्यवहृतैर्नानाशब्दैर्व्यवहार इत्यर्थः ॥ युक्त्यन्तरमप्याह—**सर्ववेदपारिषदं हीति** । हिश्चार्थे ॥ **तत्र नैकः पन्था इति** । क्वचिदन्यदेवेत्यर्थस्य बहुलग्रहणसिद्धस्यान्यैर्विभाषादिशब्दैः प्रतिपादयितुमशक्यत्वादित्यर्थः । तदुदाहरणानि च वेदेषु बहूनीति ध्वनयितुमेव लोकवेदसाधारणेपि सर्ववेदपारिषदत्वोक्तिरिति परे ॥ ५७ ॥

(२६१ तत्पुरुषसमाससंज्ञासूत्रम् ॥ २ । १ ।३ आ. ८ सू.)

४०७ श्रेण्यादयः कृतादिभिः ॥२।१।५८॥

(इष्टानुपपत्तिनिराकरणाधिकरणम्)

(गणपाठबोधकभाष्यम्)

श्रेण्यादयः पठ्यन्ते, कृतादिराकृतिगणः ॥

(प्रदीपः) **श्रेण्यादयः ॥ ५८ ॥ श्रेण्यादय इति** । अत एवात्रादिशब्दो व्यवस्थावाची, कृतादिरित्यत्रादिशब्दः प्रकारवाची प्रयोगदर्शनाच्चोदाहरणस्थानीयाः कतिपये वृत्तिकारैः प्रदर्शिता ॥

(उद्द्योतः) **श्रेण्यादयः ॥ ५८ ॥** यद्यपि वृत्त्यादौ श्रेण्यादयः कृतादयश्च पठ्यन्ते तथापि कृतादिराकृतिगण एवेति बोधयितुं भाष्ये श्रेण्यादय इति ॥

(अनिष्टापत्तिनिराकरणाधिकरणम्)

(१३२५ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ श्रेण्यादिषु च्व्यर्थवचनम् ॥ * ॥

(भाष्यम्) **श्रेण्यादिषु च्व्यर्थग्रहणं कर्तव्यम् । अश्रेणयः श्रेणयः कृताः श्रेणिकृताः । यदा हि श्रेणय एव किञ्चित् क्रियन्ते तदा मा भूदिति ॥**

(प्रदीपः) एकशिल्पपण्याश्रयणेन जीविनां संघः **श्रेणिः** । तत्र यदा पृथक् संस्थितानां श्रेणीकरणं तदा समासो यथा स्यात् यदा तु श्रेणीस्थानामेव दण्डनादिरूपकरणं तदा मा भूदिति एवमर्थमाह—**श्रेण्यादिष्वित्यादि** ॥

(उद्द्योतः) **एकशिल्पेति** । एकशिल्पाश्रयेण एकपण्याश्रयण वेत्यर्थः ॥ **तत्र यदेति** । एकशिल्पाद्यजीविसंघस्य तद्बहिष्करणमित्यर्थः । दण्डनादिरूपकरणम् । तद्योग्यरूपकरणमवरोधादीति यावत् । तदुक्तं भाष्ये—**किंचित् क्रियन्ते इति** । किंचिदर्थविशिष्टाः क्रियन्त इत्यर्थः ॥

(अनुयोगभाष्यम्)

अन्यत्रायं च्व्यर्थग्रहणेषु च्व्यन्तस्य प्रतिषेधं शास्ति । तदिह न तथा । किं कारणम् ? ॥

(प्रदीपः) **अन्यत्रेति** । **साक्षात्प्रभृतीनि चेत्यत्र च्व्यर्थवचनमित्युक्त्वा च्व्यन्ते प्रतिषेध** उक्तः, इह तु शब्दान्न कृत इति प्रश्नः ॥

(समाधानभाष्यम्)

अन्यत्र पूर्वं च्व्यन्तकार्यं परं च्व्यर्थकार्यम् । इह पुनः पूर्वं च्व्यर्थकार्यं परं च्व्यन्तकार्यम् ॥ श्रेण्यादयः ॥ ५८ ॥

(प्रदीपः) **अन्यत्र पूर्वमिति** । साक्षात्प्रभृतिष्वित्यत्र च्व्यन्तत्वे सति नित्यविकल्पितगतिसंज्ञाप्रसङ्गेन परत्वात् विकल्पः स्यादिति तत्र च्व्यन्तप्रतिषेधः क्रियते । तेन पूर्वा नित्या गतिसंज्ञा भवति । इह तु श्रेणीकृता इति परत्वान्नित्यो गतिसमासः सिध्यतीति नार्थ इह च्व्यन्तप्रतिषेधेनेत्यर्थः ॥ ५८ ॥

(उद्द्योतः) **परत्वान्नित्य इति** । ऊर्यादिच्विडाचश्चेति च्व्यन्तस्य गतित्वादिति भावः ॥ ५८ ॥

(२६२ तत्पुरुषसमाससंज्ञासूत्रम् ॥ २।१ ।३ आ. ९ सू.)

४०८ क्तेन नञ्विशिष्टेनानञ् ॥ २ । १ । ५९ ॥

(अनिष्टापत्तिनिराकरणाधिकरणम्)

(१३२६ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ नञ्विशिष्टे समानप्रकृतिग्रहणम् ॥ * ॥

(व्याख्याभाष्यम्)

नञ्विशिष्टे समानप्रकृतिग्रहणं कर्तव्यम् । इह मा भूत्—सिद्धं चाभुक्तं चेति ॥

(प्रदीपः) **क्तेन ॥५९॥** विशिष्टशब्दो यदाकथारहिताधिक्यवाच्युपात्तस्तदातिव्याप्तिपरिहारायाह—**नञ्विशिष्ट इति** । समानत्वमर्थरूपाभ्यां बोद्धव्यम् ॥

(उद्द्योतः) क्तेन नञ् ॥ ५९ ॥ अवधारणेति । नञैव विशिष्टेन नान्येनेत्येवमित्यर्थः ॥ आधिक्यवाचीति । नञधिकेनेत्यर्थः ॥ अर्थरूपाभ्यामिति । एति गच्छति जहातिजिहीतयोर्व्यावृत्तये उभयोपादानम् ॥

(१३२७ आक्षेपवार्तिकम् ॥ २ ॥)

॥ * ॥ अनञिति च ॥ * ॥

(व्याख्याभाष्यम्)

अनञिति च प्रतिषेधो वक्तव्यः । इह मा भूत्—कर्तव्यमकृतमिति ॥

(प्रदीपः) गौरवमप्यस्मिन् पक्ष इत्याह—**अनञिति चेति** । न विद्यते नञ् यस्मिन् पूर्वपदे तदनञ् तस्य प्रत्यासत्त्या क्तान्तमेवेह गृह्यते । तदयमर्थः—आधिक्यमात्रवचने विशिष्टशब्द उपादीयमाने कर्तव्यमकृतमित्यत्रापि समासप्रसङ्गः। समानप्रकृतित्वं चास्तीति वार्तिकेनापि समासो न निवारितः । ततश्चानञ्ग्रहणं क्तान्तपूर्वपदनिर्देशार्थं कर्तव्यमिति ॥

(उद्द्योतः) भाष्ये—**प्रतिषेधो वक्तव्य इति** । प्रतिषेधघटितबहुव्रीहिरूपं क्तान्तविशेषणमित्यर्थः । क्तान्तलाभार्थं तत् कर्तव्यम् । अन्यपदार्थश्च उपस्थितक्तान्त एवेति तल्लाभ इति भावः ॥ **तदयमर्थ इति** । अनञितिप्रतिषेधो वक्तव्य इति भाष्यस्यायमर्थ इत्यर्थः ॥ **ततश्चानञिति** । अवधारणसहिताधिक्यपरत्वे तु तन्न कर्तव्यं भवतीति भावः ॥

(१३२८ आक्षेपवार्तिकम् ॥ ३ ॥)

॥ * ॥ नुडिडधिकेन च ॥ * ॥

(व्याख्याभाष्यम्)

नुडिडधिकेन च समासो वक्तव्यः । इहापि यथा स्यात्—अशितानशितेन जीवति । क्लिष्टाक्लिशितेनेति ॥

(प्रदीपः) अवधारणसहिताधिक्यवचनेप्यव्याप्तिरिति तत्परिहारायाह—**नुडिडधिकेन चेति** । यद्यपि नुडिटौ तद्भक्तौ तथापि श्रुतिभेदहेतुत्वाद् अवधारणेन च श्रुतिभिन्नस्य निराकरणात्तदधिकस्याप्राप्तिरिति भावः । नुडिड्ग्रहणमागममात्रोपलक्षणार्थमिति च्छिताच्छितमित्यत्र तुगधिकस्यापि समासो भवतीति केचिदाहुः ॥ अर्थभेदमकुर्वतो विकारस्याप्युपलक्षणमिति च्छाताच्छितमित्यत्र शाच्छोरन्यतरस्यामितीत्त्वे कृते तदधिकेनापि समासो भवति । त्रातात्राणमित्यादौ तु नत्वस्यासिद्धत्वाद्भेदकत्वाभावः ॥

(उद्द्योतः) **अर्थभेदमिति** । तत्कारः विकारः केति चिन्त्यम् ॥

(अवधारणार्थत्वे प्रथमवार्तिकद्वयप्रत्याख्यानतृतीयवार्तिकावश्यकताभाष्यम्)

किमुच्यते समानप्रकृतिग्रहणं कर्तव्यमिति, यदा नञ्विशिष्टेनेत्युच्यते । न चात्र नञ्कृत एव विशेषः । किं तर्हि? । प्रकृतिकृतोपि । अयं विशिष्टशब्दोस्त्येवावधारणे वर्तते । तद्यथा—'देवदत्तयज्ञदत्तावाढ्यावभिरूपौ दर्शनीयौ पक्षवन्तौ, देवदत्तस्तु यज्ञदत्तात् स्वाध्यायेन विशिष्टः' । स्वाध्यायेनैवेति गम्यते । अन्ये गुणाः समा भवन्ति ॥ अस्त्याधिक्ये वर्तते । तद्यथा—'देवदत्तयज्ञदत्तावाढ्यावभिरूपौ दर्शनीयौ पक्षवन्तौ देवदत्तस्तु यज्ञदत्तात् स्वाध्यायेन विशिष्टः' स्वाध्यायेनाधिकः। अन्ये गुणा अविवक्षिता भवन्ति ॥ तद्यदा तावदवधारणे विशिष्टशब्दस्तदा नैवार्थः समानप्रकृतिग्रहणेन, नेह भविष्यति—सिद्धं चाभुक्तं चेति । नाप्यनञिति प्रतिषेधेन, नेह भविष्यति—कर्तव्यमकृतमिति ॥ नुडिडधिकेनापि तु तदा समासो न प्राप्नोति ॥

(प्रदीपः) **तद्यथेति** । यदा समसंप्रधारणा प्रतिपाद्यते तदावधारणे विशिष्टशब्दः । स्वरूपवर्णनमात्रे त्वाढ्यादिगुणद्वारेण क्रियमाणे आधिक्यमात्रे विशिष्टशब्दः ॥ **तद्यदेति** । इह केव सनञेति सिद्धे विशिष्टग्रहणात् सावधारणाधिक्यगतिः स्याद्, गुरुलाघवानादरे त्वाधिक्यमात्रवृत्तिर्विशिष्टशब्दो गृह्येत इति द्वैतोपपत्तिः ॥

(उद्द्योतः) **समसम्प्रधारणेति** । समयोर्मध्येन्यतरस्य संप्रधारणा गुणाधिक्यं प्रतिपिपादयिषितमित्यर्थः ॥ **अवधारणे** तद्गर्भे आधिक्ये इत्यर्थः ॥ भाष्ये—**नाप्यनञितीति** । नञैव विशिष्टेन क्तान्तेन सुबन्तं समस्यत इत्युक्ते क्तान्तप्रकृतिकमेव तल्लभ्यत इति भावः ॥ **समासो न प्राप्नोतीति** । तस्मात्तत्कर्तव्यमिति भावः ॥

(आधिक्यार्थत्वेन प्रथमवार्तिकद्वयावश्यकता तृतीयवार्तिकानावश्यकताभाष्यम्)

यदाधिक्ये विशिष्टशब्दस्तदा समानप्रकृतिग्रहणं कर्तव्यमिह माभूत्—सिद्धं चाभुक्तं चेति । अनञिति च प्रतिषेधो वक्तव्यः । इह मा भूत्—कर्तव्यमकृतमिति ॥ नुडिडधिकेनापि समासः सिद्धो भवति । तत्राधिक्ये विशिष्टशब्दं मत्वा समानप्रकृतिग्रहणं चोद्यते ॥

"अवधारणं नञा चेद् नुडिड्विशिष्टेन न प्रकल्पेत ॥

अथ चेदधिकविवक्षा, कार्ये तुल्यप्रकृतिकेन ॥ १ ॥" इति ॥

(प्रदीपः) अवधारणं नञा चेदिति । पूर्वोक्त एवार्थ आर्यया संगृहीतः अनञिलितत्सूत्रे कृतमेवेति आर्यायां कर्तव्यत्वेन नोक्तम् ॥

(न्यूनतापूर्त्यधिकरणम्)

(१३२९ आक्षेपवार्तिकम् ॥ ४ ॥)

॥ * ॥ कृतापकृतादीनां चोपसंख्यानम् ॥ * ॥

(व्याख्याभाष्यम्)

कृतापकृतादीनां चोपसंख्यानं कर्तव्यम्। कृतापकृतम्। भुक्तविभुक्तम्। पीतविपीतम् ॥

(१३३० न्यासान्तरेणाक्षेपबाधकवार्तिकम् ॥ ५ ॥)

॥*॥ सिद्धं तु क्तेन विसमासावनञ् ॥*॥

(व्याख्याभाष्यम्)

सिद्धमेतत्?। कथम्। क्तान्तेन क्रियाविसमाप्तावनञ् क्तान्तं समस्यत इति वक्तव्यम् ॥

(प्रदीपः) इदानीमप्यव्याप्त्यतिव्याप्तिपरिहाराय न्यासान्तरमप्याह—सिद्धं त्विति। विसमाप्तिरसमाप्तिः। कृताकृतमित्यत्रैकदेशे करणाकरणाभ्यां करणस्यासमाप्तिर्गम्यते इति समासः। कृतापकृतमित्यत्राप्यसमाप्तिर्गम्यते यत् कृतं तदेवापकृतं विरूपं कृतमित्यर्थावगमात्। एवं भुक्तविभुक्तमिति यद् भुक्तं तद्विभुक्तं विरूपं भुक्तमभुक्तमिति वार्थो विशब्दस्य प्रतिषेधार्थत्वात्। भुक्ते विभुक्तं चैकदेशद्वारकं भोजनकार्याकरणाद्वा बोद्धव्यम्। सिद्धमभुक्तं कर्तव्यमकृतमित्यत्र प्रतिषेधमात्रावगमाद्विसमाप्त्यभावात् समासाभावः ॥

(उद्योतः) इदानीमव्याप्त्यतिव्याप्तीति । अव्याप्तिः कृतापकृतादौ, अतिव्याप्तिः—सिद्धमभुक्तं कर्तव्यमकृतमित्यादौ प्रागुक्ता। कैयटे द्वावप्यपिशब्दौ प्रक्षिप्तौ फलाभावात् ॥ विरूपं कृतमिति। असमाप्त्यैव विरूपत्वं मध्ये तत्क्रियात्यागाच्च तस्या विरूपत्वमिति भावः ॥ अभुक्तमिति वार्थ इति। एवमपकृतमित्यस्याकृतमिति वार्थ इत्यपि बोध्यम् ॥ सिद्धमभुक्तमिति। अत्रारब्धस्यासमाप्तिर्न गम्यत इति न दोष इति भावः ॥

(१३३१ आक्षेपवार्तिकम् ॥ ६ ॥)

॥ * ॥ गतप्रत्यागतादीनां चोपसंख्यानम् ॥* ॥

(भाष्यम्) गतप्रत्यागतादीनां चोपसंख्यानं कर्तव्यम्॥ गतप्रत्यागतम्। पातानुपातम्। पुटापुटिका। क्रयाक्रयिका। फलाफलिका। मानोन्मानिका ॥ क्तेन नञ् ॥ ५९ ॥

(प्रदीपः) यत्सर्वथा वक्तव्यं तदाह—गतप्रत्यागतादीनां चेति। क्रयिकेत्यादावल्प इति कप्रत्ययस्तदन्तश्च समासात् क्वचित् स्त्रियां वर्तते। क्रयाक्रयिकेत्यन्येषामपीति दीर्घः ॥ ५९ ॥

(उद्योतः) यत्सर्वथेति। अयं भावः—सूत्रस्थनञ्विशिष्टपदं लक्षणया विसमाप्तिवचनेनेत्यर्थपरं व्याख्येयमिति सूत्रेणैव सिध्यतीति नुडिडधिकेनेत्यपि न कर्त्तव्यम्, तदाधिक्येपि विसमाप्तिवचनत्वाक्षतेरिति ॥ भाष्ये—गतप्रत्यागतमिति। गतं गमनं तदात्मकमेव प्रत्यागमनं तथोच्यते। यस्तु ग्रामान्तरं प्रति निर्गत्य तमप्राप्य मध्यत एव निवृत्तस्तदीयगमनप्रत्यागमने एकत्वेन तथा व्यवह्रियेते। यातमनुयातं तदानीमेव पुनर्गमनाद्यातानुयातम् ॥५९॥

(२६३ तत्पुरुषसमाससंज्ञासूत्रम् ॥ २।१।३ आ. १०)

४१५ युवा खलतिपलितवलिनजरतीभिः ॥ २। १। ६६ ॥

(लिङ्गविशिष्टपरिभाषासाधनाधिकरणम्)

(आक्षेपभाष्यम्)

अयुक्तोयं निर्देशः। 'समानाधिकरणेन' इति वर्तते। कः प्रसङ्गो यद्व्यधिकरणानां समासः स्यात्? ॥

(समाधानभाष्यम्)

एवं तर्हि ज्ञापयत्याचार्यः—यथाजातीयकमुत्तरपदं तथाजातीयकेन पूर्वपदेन समासो भवति—इति। किमेतस्य ज्ञापने प्रयोजनम्?। "प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणं भवति" इत्येषा परिभाषा न कर्तव्या भवति ॥ युवा ख० ॥ ६६ ॥

(प्रदीपः) युवा ॥ ६६ ॥ अयुक्त इति। पुंलिङ्गस्य स्त्रीलिङ्गेन सामानाधिकरण्यं नोपपद्यत इत्यर्थः। अनया परिभाषा ज्ञाप्यते। तेन युवतिर्जरतीति स्त्रीलिङ्गयोः समासः। नन्वेतयोरपि विरुद्धवयोवाचित्वान्नास्ति सामानाधिकरण्यम् ॥ नैष दोषः। जरत्यां युवतिधर्मोपलम्भात्। युवतेर्वा जरतीधर्मसद्भावात् तद्रूपारोपात् ॥ युवतिशब्दस्यैव पूर्वनिपातार्थमिदम्, अनियमो हि गुणशब्दत्वात् स्यात् ॥ 'जरद्भिः' इत्यपि पाठं शिष्या आचार्येण बोधिता इति युवजरन्नित्यपि भवति ॥ ६६ ॥

(उद्योतः) युवाखलति ॥ ६६ ॥ भाष्ये—यथाजातीयकमिति। स्त्रीलिङ्गशब्दरूपमित्यर्थः ॥ किमेतस्येति। लिङ्गविशिष्टपरिभाषयैव सिद्धमिति प्रश्नः॥ सा एतज्ज्ञापकसिद्धैवेत्युत्तरम्॥ यद्यपि मुखं चन्द्र इत्यादौ भिन्नलिङ्गयोरपि सामानाधिकरण्यं दृश्यते, तथापि न सर्वत्र किं तु संप्रतिपन्नस्थले एव। तदप्येकस्य नियतलिङ्गत्व एवेति भाष्याभिप्रायः ॥ तद्रूपारोपादिति। नन्वेवं

पुंस्त्वस्याप्यारोपोस्तु किं ज्ञापकेन असंगतं च तदिति चेन्न। उभयारोपे गौरवात् लक्ष्यानुरोधेन भाष्यप्रमाण्येन कृप्तपरिभाषाश्रयणस्यैवौचित्याच्चेत्यलम्॥ जरद्भिरित्यपीति। अत्र मानं चिन्त्यम्॥ युवजरतीति। बहुलग्रहणेनापि सुसाधम्॥ ६६॥

(२६४ तत्पुरुषसंज्ञासूत्रम्॥ २।१।३ आ. ११)

४१७ वर्णो वर्णेन॥ २।१।६८॥

(वर्णोवर्णेन इत्यस्य समानाधिकरणाधिकारीयत्वाधिकरणम्)

(आक्षेपभाष्यम्)

इदं विचार्यते—वर्णेन तृतीयासमासो वा स्यात्—कृष्णेन सारङ्गः कृष्णसारङ्ग इति। समानाधिकरणो वा कृष्णः सारङ्गः कृष्णसारङ्ग इति॥

(प्रदीपः) वर्णो॥ ६८॥ इदमिति। बुद्ध्या परामृष्टं वस्तु प्रत्यक्षवाचिना सर्वनाम्ना परामृश्यते। न तावदस्मिन् प्रदेशे सूत्रस्य प्रत्याख्यानम्। पश्चात्तु भविष्यति—इह कृष्णसारङ्ग इति सारङ्गशब्दः शवलपर्यायः, स च गुणोपसर्जनद्रव्यवाचित्वाद् गुणवचनो भवति। सारङ्गत्वस्य च कृष्णकृतत्वमस्ति तस्मिन्नसति तस्याभावादिति शङ्कुलाखण्डवत्समासः सिद्धः। अथ कृष्णावयवत्वात् सारङ्गवृत्तिः कृष्णशब्दः तदा समानाधिकरणपदः समासः। स च गौणेपि सामानाधिकरण्ये बहुलवचनाद्विशेषणं विशेष्येणेति सिद्ध इति॥ कृष्णेनेति। हेतुतृतीया॥

(उद्योतः) वर्णोव॥ ६८॥ बुद्ध्या परामृष्टमिति। वक्ष्यमाणमसन्निहितमपि विचारविषयमित्यर्थः। बुद्धिविषयत्वेनैव च प्रत्यक्षता॥ नन्विदंशब्देन सूत्रमेव गृह्यतां तत्राह—न तावदिति। सूत्रकर्तव्यत्वाकर्तव्यत्वविचारो नात्रेति न तस्येदमा परामर्श इति भावः॥ अस्मिन्प्रदेश इति पाठः। कस्मिन् प्रकरणे सूत्रं कार्यमित्येवात्रत्यविचारतात्पर्यमित्याशयः॥ पश्चाद्भाविप्रत्याख्यानप्रकारं मन्दबुद्धिव्युत्पत्तये सौकर्याय च दर्शयति—इह कृष्णसारङ्ग इतीति॥ विशेषणं विशेष्येणेति सिद्ध इति प्रत्याख्यानं तु पश्चाद्भविष्यतीत्यन्वयः॥ षष्ठीसमासस्त्वीदृशे विषये न संभवत्येव। भाष्यप्रामाण्येनानभिधानाच्च॥ गौणेपीति। बहुलग्रहणात् गौणमुख्यन्यायोत्र न प्रवर्त्तत इति भावः॥ विशिष्टरूपोपादानाभावात्, लाक्षणिकतामात्रेण गौणत्वाभावाच्च चिन्त्यमिदम्॥ भाष्ये—वर्णेन तृतीयासमासो वा स्यादिति। वर्णो वर्णेनेति सूत्रं तृतीया तत्कृतेत्यनन्तरं कार्यम्, उतात्रैवेति विचार्यत इत्यर्थः॥ ननु तृतीयासमासस्य तत्कृतत्वेनैव सिद्धेस्तत्प्रकरणे इदं व्यर्थमत आह—हेतुतृतीयेति। हेतुतृतीयान्ते हि तस्य न प्राप्तिरिति भावः॥

(विशेषप्रश्नभाष्यम्)

कश्चात्र विशेषः?॥

(प्रदीपः) कश्चात्रेति। क लाघवमिति प्रश्नः॥

(१३३२ तृतीयासमासे दूषणवार्तिकम्॥ १॥)

॥ * ॥ वर्णेन तृतीयासमास एतप्रतिषेधे वर्णग्रहणम्॥ * ॥

(भाष्यम्) **वर्णेन तृतीयासमासे एतप्रतिषेधे वर्णग्रहणं कर्तव्यम्। तृतीयापूर्वपदं प्रकृतिस्वरं भवति। "अनेते वर्णः" इति वक्तव्यम्॥ [इह मा भूत्—हिमेन एतः हिमैतः॥]**

(प्रदीपः) एतप्रतिषेध इति। स्वरे विधीयमान इत्यर्थः॥ अनेते वर्ण इति। कृष्णसारङ्ग इत्यादौ तत्पुरुषे तुल्यार्थतृतीयेति पूर्वपदप्रकृतिस्वरे सिद्धे अनेते वर्ण इति सूत्रं कर्तव्यम्। वर्णवाचि पूर्वपदमेत उत्तरपदे प्रकृतिस्वरं न भवतीत्यर्थः॥ तेन कृष्णैत इति समासान्तोदात्तत्वमेव भवति। कृष्णेनेति सहयोगे इत्थंभूतलक्षणे वा तृतीया, अनेन समासः॥ वर्णग्रहणाच्च हिमेन एतो हिमैत इत्यादौ पूर्वपदप्रकृतिस्वर एव भवति। हिमेनेति हेतौ तृतीया, तत्कृतार्थेति समासः। कृत्स्वरस्तु नास्ति उणादीनामव्युत्पन्नत्वाद् अकारकत्वाद्वा हिमस्य॥

(उद्योतः) प्रकृतिस्वरे सिद्धइति। अतिप्रसङ्गनिवारणार्थमिति शेषः। अनेते वर्ण इति सूत्रं कर्त्तव्यमित्यन्वयि॥ तेन कृष्णैत इति। एतः शवलः। 'शवलैताश्च कर्बुरे' इतिकोशात्॥ एत उत्तरं कृष्णेनेति सहयोगे इत्थंभूतलक्षणे वा तृतीया अनेनैव समास इति ग्रन्थः कैयटे दृश्यते सोऽग्रन्थः। एतशब्दस्य कृष्णघटितवर्णसमुदायवदर्थकत्वेन साहित्यस्य ज्ञापकत्वस्य चात्यन्तभेदनियतत्वेन सहयोगे तृतीयाया इत्थंभूततृतीयायाश्चाप्राप्तेः। कृष्णसारङ्गोक्तरीत्या सिद्धे उपयोगाभावाच्चेति केचित्॥ पूर्वपदप्रकृतिस्वरो भवतीति। पूर्वपदस्य हिमशब्दस्य वर्णवाचित्वाभावान्निषेधाप्राप्तेरित्यर्थः। अनेते वर्ण इति प्रथमान्तम्॥ नन्वत्र वर्णो वर्णेनेति न प्राप्नोति हिमस्य वर्णत्वाभावादत आह—हेतौ तृतीयेति। जनकत्वसाम्याद्धेतुपदं कर्तृपलक्षणं कृतद्वारकं च सामर्थ्यमिति भावः। तदाह—तत्कृतार्थेति समास इति॥ अकारकत्वाद्वेति। कृतद्वारकसामर्थ्ये एव समासत्वेनैतपदार्थे प्रत्यकारकत्वादित्यर्थः॥

(आक्षेपभाष्यम्)

अथ द्वितीयेन वर्णग्रहणेनैतविशेषणेनार्थः?॥

(उद्योतः) भाष्ये—द्वितीयेनेति। सप्तम्यन्तेनेत्यर्थः। नैते वर्णे वर्णे इतिसूत्रं पाठ्यमिति भावः। अनेत इत्यस्यासमर्थसमासत्वेन वा न क्षतिरिति॥

(समाधानभाष्यम्)

बाढमर्थः । यद्यवर्ण एतशब्दोऽस्ति ॥

(प्रदीपः) **यद्यवर्ण इति** । वर्णग्रहणस्य व्यवच्छेद्यत्वेन प्रयोजको नास्तीति भावः ॥

(उद्द्योतः) भाष्ये—यद्यन्तर्भावेन सूचितं तदभावमाह—**प्रयोजकोनास्तीति** । तृतीया कर्मणीत्यादिप्रवृत्तेरिति भावः ॥

(समाधानबाधकभाष्यम्)

ननु चायमस्ति—आ इतः एतः, कृष्णेतो लोहितेत इति ॥

(प्रदीपः) इतरः पराभिप्रायमबुद्ध्वा सत्तां प्रतिपादयितुमाह—**ननु चेति** ॥ **कृष्णेत इति** । **ओमाङोश्चेति** पररूपम् ॥

(प्रत्याख्यानभाष्यम्)

नार्थ एवमर्थेन वर्णग्रहणेन । यदि तावदयं कर्मणि क्तः, "तृतीया कर्मणि" इत्यनेन स्वरेण भवितव्यम् । अथापि कर्तरि, परत्वात्कृत्स्वरेण भवितव्यम् ॥

(प्रदीपः) **तृतीयाकर्मणीति** । अनेत इति प्रतिषेध आनन्तर्यान्मध्येऽपवादा इति वा **तत्पुरुषे तुल्यार्थे**त्यस्यैव बाधक इत्यभिप्रायः ॥ **परत्वादिति** । कृष्णेन अश्वादिना करणेन आगतः कृष्णेत इत्यत्र—**अनेत** इति प्रतिषेधः पूर्वपदप्रकृतिस्वरस्य किं बाधकोऽस्तु अथ वा कृत्स्वर इति विचारे परत्वात् कृत्स्वर एव बाधक इति नार्थ एतविशेषणार्थेन वर्णग्रहणेनेत्यर्थः । कृत्स्वरमपि बाधित्वा **थाथादि**स्वरेणात्र भाव्यं विशेषाभावात्तु भाष्यकारेणैतन्नोक्तम् ॥ अथ वा **परत्वा**दुत्कृष्टत्वात् कक्ष्यान्तरप्राप्तत्वात् कृत्स्वरः थाथादिस्वर इत्यर्थः ॥

(उद्द्योतः) नन्वेत इति तृतीया कर्मणीत्यस्यापि निषेधः स्यादत आह—**आनन्तर्यादित्यादि** ॥ अनेत इत्यस्य पूर्वपदप्रकृतिस्वरनिषेधत्वात्कृत्स्वरस्य च पूर्वपदप्रकृतिस्वरापवादत्वात् **परत्वादि**त्यसंगतं तत्राह—**अनेत इति प्रतिषेध इति** । पूर्वपदप्रकृतिस्वरस्य बाधकः किम्प्रतिषेधोऽथ कृत्स्वर इत्यन्वयः ॥ **विशेषाभावात्त्विति** । एतशब्दस्यान्तोदात्तत्वादिति भावः ॥ **निषेधाश्च बलीयांस** इति न्यायमभिप्रेत्याह—**अथ वेति** ॥ **कक्ष्यान्तरप्राप्तत्वादिति** ॥ पूर्वपदप्रकृतिस्वरापवादकृत्स्वरापवादत्वादित्यर्थः ॥

(समानाधिकरणपक्षाभ्युपगमभाष्यम्)

अथ समानाधिकरणः ॥

(१३३३ समानाधिकरणपक्षे दूषणवार्तिकम् ॥ २ ॥)

॥ * ॥ समानाधिकरणे द्विर्वर्णग्रहणम् ॥ * ॥

(व्याख्याभाष्यम्)

समानाधिकरणे द्विर्वर्णग्रहणं कर्तव्यम् । वर्णो वर्णेष्वनेत इति वक्तव्यम् । एकं वर्णग्रहणं कर्तव्यम् । इह मा भूत्—परमशुक्लः परमकृष्णः । द्वितीयं वर्णग्रहणं कर्तव्यम् । इह मा भूत्—कृष्णतिला इति ॥

(उद्द्योतः) भाष्ये—**द्विर्वर्णग्रहणमिति** । अनेत इति प्रतिषेध इत्यनुषज्यते ॥

(दूषणबाधकभाष्यम्)

एकं वर्णग्रहणमनर्थकम् ॥

(उद्द्योतः) आचार्यदेशीयः प्रकृतसूत्रसत्ताश्रयणेन प्रतिपदोक्तपरिभाषया सिद्धिमाश्रित्यैकवर्णग्रहणकरणेन पक्षयोः साम्यं दर्शयति—भाष्ये—**एकं वर्णग्रहणमिति** ॥

(आक्षेपभाष्यम्)

अवर्णस्य वर्णे वर्णस्य चावर्णे अन्यतरत्र कस्मान्न भवति ? ॥

(उद्द्योतः) **अन्यतरत्र कस्मादिति** । अवर्णस्य वर्णे, वर्णस्य वा अवर्णे कस्मान्न भवतीत्यर्थः । क्वचित्तु तथैव पाठः ॥

(समाधानभाष्यम्)

'लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव' इति ॥

(प्रदीपः) **लक्षणप्रतिपदोक्तयोरिति** । **वर्णो वर्णेनेति** यः समास स एव स्वरविधौ द्वितीयवर्णग्रहणमन्तरेणापि ग्रहीष्यते तेनातिप्रसङ्गो न भविष्यतीत्यर्थः ॥

(तृतीयासमासवादिभाष्यम्)

एवं सति तान्येतानि त्रीणि वर्णग्रहणानि भवन्ति—समासविधौ द्वे, स्वरविधौ चैकम् ॥

(समानाधिकरणसमासवादिभाष्यम्)

यस्यापि तृतीयासमासस्तस्यापि तान्येव त्रीणि वर्णग्रहणानि भवन्ति । समासविधौ द्वे, स्वरविधौ चैकम् ॥

(तृतीयासमासवादिभाष्यम्)

सामान्येन मम तृतीयासमासो भविष्यति "तृतीया तत्कृतार्थेन गुणवचनेन" इति ॥

(उद्द्योतः) अथ तृतीयासमासवादी स्वमते लाघवमाह—**सामान्येन ममेति** ॥

(समानाधिकरणसमासवादिभाष्यम्)

अवश्यं वर्णेन प्रतिपदं समासो वक्तव्यः । यत्र तेन न सिध्यति तदर्थम् ॥ क्व च तेन न सिध्यति ? । शुकबभ्रुर्हरितबभ्रुरिति ॥ तथा सति तान्येतानि त्रीणि वर्णग्रहणानि भवन्ति—समासविधौ द्वे, स्वरविधौ चैकम् ॥

(प्रदीपः) **शुकबभ्रुरिति** । शुको हरितः शुक्रो वा बभ्रुः कपिलः । ततः तत्कृतत्वाभावात् शुकेन बभ्रुरिति तृतीया सहयोग इत्थंभूतलक्षणे वा कर्तव्या ॥

(उद्द्योतः) इतर आह—अवश्यं वर्णेति ॥ यद्यपि हेतुतृतीयान्तेन समासार्थं कृष्णसारङ्ग इत्याद्यर्थमावश्यकम् तथापि स्पष्टत्वाय यत्र कृतद्वारकसामर्थ्यस्यासंभवस्तदर्थमित्याह—शुकबभ्रुरिति । सहयोगे तृतीयेत्येव न्यायम् ॥

(तृतीयासमासवादिभाष्यम्)

अथेदानीं समानाधिकरणः सामान्येन सिद्धः स्यात्? ॥

(उद्द्योतः) स एव पुनः पृच्छति—अथेदानीमिति ॥

(समानाधिकरणसमासवादिभाष्यम्)

बाढं सिद्धः ॥ कथम्?। "विशेषणं विशेष्येण बहुलम्" इति। एवमपि द्वे वर्णग्रहणे कर्तव्ये स्वरविधावेव, प्रतिपदोक्तस्याभावात्। तस्मात्समानाधिकरण इत्येष पक्षो ज्यायान् ॥

(प्रदीपः) तस्मादिति । एतत्सूत्रानारम्भाल्लाघवादित्यर्थः ॥

(उद्द्योतः) सिद्धान्त्याह—बाढमिति ॥ एवमपीति । एवं चेत्यर्थः ॥ इदं सूत्रमत्र पक्षे उदाहरणमात्रपरमिति बोध्यम् ॥

(प्रधानोपसर्जनानां विप्रतिषेधाधिकरणम्)

(१३३४ वार्तिकम् ॥ ३ ॥)

॥ * ॥ समानाधिकरणाधिकारे प्रधानोपसर्जनानां परं परं विप्रतिषेधेन ॥ * ॥

(भाष्यम्) समानाधिकरणाधिकारे प्रधानोपसर्जनानां परं परं भवति विप्रतिषेधेन । प्रधानानां प्रधानम्, उपसर्जनानामुपसर्जनम् । प्रधानानां तावत्प्रधानम्—"वृन्दारकनागकुञ्जरैः पूज्यमानम्" इत्यस्यावकाशः—गोवृन्दारकः अश्ववृन्दारकः । "पोटायुवतीनामवकाशः—इभ्ययुवतिः, आढ्ययुवतिः । इहोभयं प्राप्नोति—नागयुवतिः वृन्दारकयुवतिः । प्रधानानां परं प्रधानं भवति विप्रतिषेधेन ॥ उपसर्जनानां परमुपसर्जनम् । "सन्महत्परमोत्तमोत्कृष्टा" इत्यस्यावकाशः—सद्गवः सदश्वः । "कृत्यतुल्याख्या अजात्या" इत्यस्यावकाशः—तुल्यश्वेतः तुल्यमहान् । इहोभयं प्राप्नोति—तुल्यसन् तुल्यमहान् । उपसर्जनानां परमुपसर्जनं भवति विप्रतिषेधेन ॥

(प्रदीपः) प्रधानोपसर्जनानामिति । प्रधानग्रहणेन समासशास्त्रे तृतीयान्तानि लक्ष्यन्ते उपसर्जनशब्देन समासशास्त्रे प्रथमानिर्दिष्टमुच्यते ॥

(उद्द्योतः) क्वचिद्विशेषणविशेष्यभावे कामचारात्प्रधानोपसर्जनत्वे व्यवस्थिते तत्राह—प्रधानग्रहणेनेति । तदयमर्थः—पूर्वपरसूत्रोपात्तप्रधानयोः सह समाससंज्ञाप्रसङ्गे परसूत्रोपात्तं प्रधानं[प्रधानं] भवति पूर्वसूत्रोपात्तं प्रधानमुपसर्जनम् । तादृशोपसर्जनयोः समासप्रसङ्गे परशास्त्रोपात्तमुपसर्जनमुपसर्जनम्, पूर्वसूत्रोपात्तमुपसर्जनं प्रधानमिति ॥ भाष्ये इभ्ययुवतिराढ्ययुवतिरिति पाठः स चिन्त्यः । तयोरजातित्वात् । इभयुवतिरश्वयुवतिरिति पाठस्तु उचित इति केचित् ॥ भाष्यप्रामाण्यात्तयोरपि जातिवाचित्वम् । अत एव जातेरस्त्रीतिसूत्रेऽयोपधादित्यस्य इभ्या क्षत्रियेति प्रत्युदाहरणं भाष्ये दत्तम् । हस्तिपकजातिश्चेभ्यपदेनोच्यते ॥ अर्घ्येति पाठः । अर्घ्यो ब्राह्मण इत्यन्ये ॥ वृन्दारकयुवतिरिति । वृन्दारकशब्दो देवजातिवाचीत्याहुः ॥ भाष्ये—कृत्यतुल्येत्यस्यावकाशप्रदर्शनावसरे तुल्यमहानित्यपपाठः । तुल्यश्वेतः तुल्यकृष्ण इत्येव पाठ्यः पाठः ॥

(न कर्मधारयान्मत्वर्थीय इति व्युत्पत्तिसाधकाधिकरणम्)

(१३३५ बहुव्रीहेः कर्मधारयप्रकृतिकमत्वर्थीयापवादत्वसाधकप्रथमखण्डवार्तिकम् ॥ ४ ॥)

॥ * ॥ समानाधिकरणसमासाद् बहुव्रीहिः ॥ * ॥

(भाष्यम्) समानाधिकरणसमासाद्बहुव्रीहिर्भवति विप्रतिषेधेन ॥ समानाधिकरणसमासस्यावकाशः—वीरः पुरुषो वीरपुरुषः । बहुव्रीहेरवकाशः—कण्ठेकालः । इहोभयं प्राप्नोति—वीरपुरुषको ग्रामः । बहुव्रीहिर्भवति विप्रतिषेधेन ॥

(प्रदीपः) समानाधिकरणसमासादिति ।* समानाधिकरणसमासाद् बहुव्रीहिः कदाचित् कर्मधारयः सर्वधनाद्यर्थं* इति वार्तिककारेणेष्टिरूपेण पठितम् ॥ भाष्यकारस्तु न्यायव्युत्पादनाय विप्रतिषेधमुपन्यस्य दूषयित्वा इष्टिरूपतां स्थापयिष्यति प्रत्यासत्तेः सामर्थ्यस्य बलवत्त्वाश्रयेण॥ कण्ठेकाल इति । व्यधिकरणानां बहुव्रीहिः सप्तम्यन्तस्य पूर्वनिपातविधानेन ज्ञाप्यते ॥ वीरपुरुषक इति । बहुव्रीहिसंज्ञायां सत्यां पूर्वपदप्रकृतिस्वरः शाक्तिकश्च कप्समासान्तो भवति । बहुव्रीहिसंज्ञायां शेषग्रहणे प्रत्याख्याते विप्रतिषेधश्चिन्त्यते ॥

(उद्द्योतः) न्यायव्युत्पादनायेति । प्रत्यासत्त्यादिन्यायेत्यर्थः ॥ विप्रतिषेधप्रकरणादिष्टिरूपत्वं कथं लभ्यमित्यत आह—प्रत्यासत्तेरिति ॥ ज्ञाप्यते इति । शेषत्वाभावादिति भावः ॥ शेषग्रहणे प्रत्याख्याते इति । तथासत्येव कण्ठेकाल इति तदवकाशो युज्यते इति भावः । नहि ज्ञापकसिद्धे सावकाशत्वं गृहीत्वा सूत्रेण विप्रतिषेधो युक्तो विचारयितुमित्यभिमानः ॥ अयं ग्रन्थः प्रौढ्या, नहि त्रिकतः शेषे एकसंज्ञाधिकारे च तत्प्रत्याख्यानमस्ति । व्यधिकरणसमासस्यात्यल्पविषयतासूचनार्थं तस्यावश्यकत्वाच्चेति केचित् ॥

(१२३६ कर्मधारयप्रकृतिकमत्वर्थीयसाधकवार्तिकद्वितीयखण्डम् ॥ ५ ॥

॥ * ॥ कदा चित्कर्मधारयः सर्वधनाद्यर्थः ॥ * ॥

(भाष्यम्) **कदाचित्कर्मधारयो भवति बहुव्रीहेः ॥ किं प्रयोजनम्? । सर्वधनाद्यर्थः । सर्वधनी । सर्वबीजी । सर्वकेशी नटः । गौरखरवदरण्यम् । कृष्णसर्पवान्वल्मीकः । लोहितशालिमान् ग्रामः ॥ किं प्रयोजनम्? । कर्मधारयप्रकृतिभिर्मत्वर्थीयैरभिधानं यथा स्यात् ॥ किं च कारणं न स्यात्? । बहुव्रीहिणोक्तत्वान्मत्वर्थस्य ॥**

(प्रदीपः) **कदाचिदिति** । विषयविशेषनिर्देशाय क्वचिदिति वक्तव्ये कदाचिदित्यनेन विषयविशेषावच्छिन्नः कालविशेषो निर्दिश्यत इति नास्ति वस्तुभेदः ॥ **सर्वधनीति** । सर्वाणि धनान्यस्येत्यर्थविवक्षायां कर्मधारये कृते मत्वर्थीय इति तदर्थं पूर्वविप्रतिषेध आश्रयणीय इत्युक्तं भवति ॥ **किं प्रयोजनमिति । सर्वधनाद्यर्थ**मिति मत्वर्थीयरहितस्य सर्वधनशब्दस्योपादानात्तस्य च केवलस्यान्यपदार्थविवक्षायां प्रयोगादर्शनाच्च स्वपदार्थे बहुव्रीहेरप्रसङ्गात् कर्मधारयस्यानुक्तसिद्धत्वात् प्रश्नः ॥ **कर्मधारयप्रकृतिभिरिति** । मत्वर्थीयप्रकृतिः सर्वधनशब्दो वार्तिकेऽनुकृतः न तु स्वतन्त्र इत्यर्थः ॥ **बहुव्रीहिणेति** । सर्वाणि धनान्यस्येति विवक्षायां यदि बहुव्रीहिः क्रियते तदा तेनैव मत्वर्थस्योक्तत्वान्मत्वर्थीयो न स्यात्, कर्मधारये तु सति तेन मत्वर्थस्यानुक्तत्वात् प्रत्ययः सिध्यतीत्यर्थः ॥

(उद्द्योतः) कदाचिदित्यनेन समासद्वयस्यैकविषयत्वमाशङ्क्याह—**विषयविशेषेति** ॥ **नास्ति वस्तुभेद इति** । क्वचिदित्यतो नार्थभेद इत्यर्थः ॥ भाष्ये—**सर्वधनाद्यर्थ इति** । सर्वधनादिप्रकृतिकमत्वर्थीयार्थमित्यर्थः ॥ प्रयोजनस्योक्तत्वात् **किम्प्रयोजन**मिति प्रश्नानुपपत्तिमाशङ्क्याह—**सर्वधनेति** ॥ **प्रयोगादर्शनाच्चे**ति रहितः पाठः ॥ वाक्यालंकारे वा चः ॥ **कर्मधारयस्यानुक्तसिद्धत्वादिति** । कदाचित्कर्मधारय इति पूर्वविप्रतिषेधानुक्तावपि सिद्धत्वादित्यर्थः ॥ **मत्वर्थीयप्रकृतिरिति** । षष्ठीतत्पुरुषः ॥ भाष्ये—**मत्वर्थीयैरभिधानमिति** । तैः प्रत्ययैस्तदर्थाभिधानं यथा स्यादित्यर्थः ॥

(मत्वर्थीयोत्पत्तिबाधकाक्षेपभाष्यम्)

यद्युक्तत्वं हेतुः, कर्मधारयेणाप्युक्तत्वान्न प्राप्नोति ॥ न खल्वपि संज्ञाश्रयो मत्वर्थीयः । किं तर्हि? । अर्थाश्रयः ॥ स यथैव बहुव्रीहिणोक्तत्वान्न भवति, एवं कर्मधारयेणोक्तत्वान्न भविष्यति ॥

(प्रदीपः) **यद्युक्तत्वमिति** । सर्वाणि धनान्यस्येत्यर्थविवक्षायां पूर्वविप्रतिषेधेन यदि कर्मधारयः क्रियते तदा तेनापि मत्वर्थ उच्यत एव । नहि बहुव्रीहिकर्मधारयसंज्ञाभेदमात्रेण स्वरूपनस्थावत्पदार्थस्याभिधानानभिधानव्यवस्था युज्यते, तस्याः स्वाभाविकत्वात् ॥

(उद्द्योतः) **तस्याःस्वाभाविकत्वादिति** । बहुव्रीहिविषये पूर्वविप्रतिषेधेन कर्मधारयविधानात्तदर्थस्तेनोक्त एवेति भावः ॥

(मत्वर्थीयोत्पत्तिसाधकसमाधानभाष्यम्)

एवं तर्हि इदं स्यात्—सर्वाणि धनानि=सर्वधनानि, सर्वधनान्यस्य सन्ति=सर्वधनीति ॥

(प्रदीपः) **एवं तर्हीति** । अनपेक्षितान्यपदार्थे स्वपदार्थे कर्मधारयं कृत्वा मत्वर्थीयोऽर्थान्तरे विधास्यत इत्यर्थः ॥

(उद्द्योतः) **मत्वर्थीयोऽर्थान्तर इति** । अन्यपदार्थरूपे मत्वर्थे इत्यर्थः ॥

(वार्तिकीयकदाचित्पदासंगत्याक्षेपभाष्यम्)

नैवं शक्यम् । नित्यमेवं सति कर्मधारयः स्यात् । तत्र यदुक्तम्—"कदाचित्कर्मधारयः" इति, एतदयुक्तम् ॥

(प्रदीपः) **नित्यमेवं सतीति** । यथा पूर्वं विषयभेदविवक्षया कदाचिदित्युक्तं तथात्र सकलविषयव्याप्त्यपेक्षया सर्वत्रेति वक्तव्ये नित्यमित्युक्तम् । एतदुक्तं भवति—अनेन न्यायेन सर्वत्र मत्वर्थीयप्रकृतिभिः कर्मधारयः स्यादिति कदाचिद् ग्रहणं विषयविशेषनिर्देशार्थं न वक्तव्यं भवति ॥

(उद्द्योतः) **न वक्तव्यमिति** । वक्तुमनर्हमित्यर्थः । क्वचित्तु न कर्तव्यमितिपाठः । तत्राप्ययमेवार्थः, तदर्थस्य विषयविशेषनिष्ठत्वस्याभावादिति भावः ॥

(वार्तिकाशयान्तरभाष्यम्)

एवं तर्हि भवति वै किंचिदाचार्याः कार्यबुद्धिं कृत्वा पठन्ति—"कार्याः शब्दाः" इति, तद्वदिदं पठितम्— * समानाधिकरणसमासाद्बहुव्रीहिः कर्तव्यः कदाचित्कर्मधारयः सर्वधनाद्यर्थः * इति ॥

(प्रदीपः) इदानीमन्यथा मत्वर्थीयोत्पत्तिमाह—**एवं तर्हीति ॥ भवतीति** । एवंजातीयकं वस्त्वित्यर्थः ॥ किं तदित्याह—**आचार्या इति** । अथ वा पठिक्रिया भवतिक्रियायाः कर्त्री भवति । कार्याः शब्दा इति दर्शने लक्षणादेव शब्दानामर्थव्यवस्था ततोन्यपदार्थे बहुव्रीहिशासनात्तस्यैव तत्प्रत्यायनम्, न तु कर्मधारयस्य । तत्र सर्वाणि धनान्यस्येत्यर्थविवक्षायां पूर्वविप्रतिषेधेन कर्मधारयः क्रियमाणोऽन्यपदार्थं नाभिधत्त इति तदभिधानायायं मत्वर्थीय उत्पाद्यत इत्यर्थः ॥

(उद्द्योतः) **अन्यथा**, प्रकारान्तरेण ॥ **मत्वर्थीयोत्पत्तिं**, तन्नियमम् ॥ **वस्त्वित्यर्थ इति । भवति वै किंचिदिति** भाष्यस्य एवंजातीयकं किंचिद्वचनं भवति खल्वित्यर्थः । किंजातीयमित्याशङ्कायां **कार्याः शब्दा** इति यज्जातीयं, तज्जातीयमित्युत्तरम् ॥

कार्याः शब्दा इति वचनमेव केनाभिप्रायेण पठितमित्यत आह—**आचार्याः कार्यवद्बुद्धिं कृत्वा पठन्तीति ।** घटादिरूपकार्यवच्छब्दा अपि कार्या इति बुद्ध्या पठन्तीत्यर्थः ॥ पठ्यमानवचनाकारमाह—**कार्याः शब्दा इति ॥ अथवा पठिष्यतेति ।** आचार्यकर्तृककिंचित्कर्मककार्यत्वबुद्धिकरणोत्तरकालिकपठनक्रियाकर्तृकं भवनमित्यर्थः ॥ दृष्टान्तमुपपाद्य प्रकृतोपयुक्तमाह—**तद्वदिति ।** कार्याः शब्दा इति वत्कार्यवद्बुध्येदं पठितमित्यर्थः ॥ तदाशयमाह—**कार्याः शब्दा इति दर्शने इति ॥ तत्प्रत्यायनम् ।** तत्प्रत्यायनसामर्थ्यम् ॥

(विप्रतिषेधासंभवेन बहुव्रीहिनिराकरणाक्षेपभाष्यम्)

यदुच्यते—समानाधिकरणसमासाद्बहुव्रीहिर्भवति विप्रतिषेधेन—इति ॥ नैष युक्तो विप्रतिषेधः । अन्तरङ्गः कर्मधारयः ॥ काऽन्तरङ्गता ? । स्वपदार्थे कर्मधारयः । अन्यपदार्थे बहुव्रीहिः ॥

(प्रदीपः) विप्रतिषेधापनयनायाह—**नैष युक्त इति ॥ स्वपदार्थ इति ।** मध्यमध्यमवीराश्चेति स्वपदार्थमात्राश्रयेण विधानादन्यपदार्थानाश्रयणादिति भावः ॥

(बहुव्रीहिसाधकसमाधानभाष्यम्)

अस्तु । विभाषा कर्मधारयः, यदा न कर्मधारयस्तदा बहुव्रीहिर्भविष्यति ॥

(प्रदीपः) इतरो विषयविशेषे बहुव्रीहिं साधयति—**अस्त्विति ।** यथोक्तेन प्रकारेणान्तरङ्गत्वं कर्मधारयस्य भवत्वित्यर्थः ॥ **विभाषेति ।** नात्र महाविभाषा विवक्षिता, तया हि पक्षे व्यपेक्षैव प्रतिपाद्यते नत्वेकार्थीभावे संज्ञाया भावाभावौ क्रियेते । तस्माद्—**विभाषा कर्मधारय** इत्यस्यायमर्थः—विकल्पितः कर्मधारयो विषयविभागेनावस्थानात् स्वपदार्थे ह्यसौ वर्तते नान्यपदार्थे ॥ एतदुक्तं भवति—अनपेक्षितान्यपदार्थस्वपदार्थमात्रविवक्षायां भवतु कर्मधारयः, पूर्वमेव त्वन्यपदार्थविवक्षायां वीरपुरुष इत्यादौ बहुव्रीहिः सिध्यति ॥

(उद्द्योतः) नन्वेवं वीरः पुरुष इत्यादौ अन्तरङ्गत्वात् कर्मधारय एव स्यात् नतु बहिरङ्गो वीरपुरुषक इति बहुव्रीहिरित्यत आह—भाष्ये—**अस्तु, विभाषेति ॥** तदाशयमाह—**नात्रे**त्यादिना ॥ **बहुव्रीहिः सिध्यतीति ।** अपवादत्वादिति भावः ॥

(आक्षेपभाष्यम्)

एवमपि यद्यत्र कदाचित्कर्मधारयो भवति । कर्मधारयप्रकृतिभिर्मत्वर्थीयैरभिधानं प्राप्नोति । सर्वश्चायमेवमर्थो यत्नः—कर्मधारयप्रकृतिभिर्मत्वर्थीयैरभिधानं मा भूद्—इति ॥

(प्रदीपः) **एवमपीति ।** पूर्वमनपेक्षितेऽन्यपदार्थे यदि कर्मधारयः क्रियते तदा पश्चादन्यपदार्थविवक्षायां वीरपुरुषवान् ग्राम इत्याद्यपि स्यादित्यर्थः ॥

(समाधानभाष्यम्)

एवं तर्हि नेदं तस्य योगस्योदाहरणं "विप्रतिषेधे परम्" इति ॥ किं तर्हि ? । इष्टिरियं पठिता—'समानाधिकरणसमासाद्बहुव्रीहिरिष्टः । कदाचित्कर्मधारयः सर्वधनाद्यर्थः' इति ।

(प्रदीपः) **इष्टिरियमिति ।** वीरपुरुषादौ प्रथममेवान्यपदार्थविवक्षा कार्या, सर्वधनीत्यादौ तु पश्चादिति विवक्षानियम इष्टसिद्धये प्रतिपाद्यत इत्यर्थः ॥

(उद्द्योतः) भाष्ये—इष्टिरियमित्यनेन यदुक्तं तद्दर्शयति—**प्रथममेवेति ।** वीरपुरुषादौ यद्यन्यपदार्थविवक्षा तर्हि प्रथममेव, न तु कर्मधारयोत्तरमित्यर्थः । इदमेवार्थतः पठ्यते **न कर्मधारयान्मत्वर्थीय** इति ॥

(उक्तवार्त्तिकानावश्यकतासाधकैकदेशिभाष्यम्)

यदीष्टिः पठिता, नार्थोऽनेन । इह हि सर्वे मनुष्या अल्पेनाल्पेन महतो महतोऽर्थानाकाङ्क्षन्ति । एकेन माषेण शतसहस्रम् । एकेन कुद्दालपदेन खारीसहस्रम् । तत्र कर्मधारयप्रकृतिभिर्मत्वर्थीयैरभिधानमस्तु बहुव्रीहिणेति । बहुव्रीहिणा भविष्यति लघुत्वात् ॥

(प्रदीपः) **नार्थोऽनेनेति ।** न्यायसिद्धत्वादिति भावः । यदि कर्मधारयान्मत्वर्थीयः क्रियते, तदा स्वपदार्थप्राधान्यमाश्रित्य कर्मधारयः कर्तव्यः, तेषामेव पदार्थानामन्यत्र गुणीभावमाश्रित्य मत्वर्थीय उत्पाद्यत इति प्रतिपत्तिगौरवप्रसङ्गः । यदा पूर्वमेवान्यपदार्थविवक्षा तदा वर्तिपदार्थानां तत्र गुणभाव एवाश्रीयत इति प्रतिपत्तिलाघवं भवति ॥ अन्ये तु शब्दलाघवं मन्यन्ते बहुव्रीहिरन्यानपेक्षोऽन्यपदार्थं प्रतिपादयति । कर्मधारयस्तु मत्वर्थीयसहित इति शब्दगौरवप्रसङ्गः । एतच्च शब्दगौरवं तथा प्रयोगदर्शनादत्रैव विषय आश्रीयत इति वृक्षवनस्पत्यादिषु न प्रसञ्जनीयम् ॥

(उद्द्योतः) भाष्ये—**अल्पेनेति ।** द्रव्येणेत्यर्थः । **अल्पेन यत्नेनेति** क्वचित्पाठः ॥ **माषेण ।** तत्परिमितस्वर्णेन ॥ **शतसहस्रमिति ।** वस्त्राणि गा वेत्यर्थः ॥ **कुद्दालपदेनेति ।** पर्वतीयाः कुद्दालैरेव भूकर्षणं कृत्वा सस्यं संपादयन्तीति तद्व्यवहारानुसारेणेदम् ॥ **प्रतिपत्तिगौरवेति ।** एकस्य विरुद्धयोः प्राधान्यगुणत्वयोराश्रयणमेव प्रतिपत्तिगौरवमित्याहुः ॥ **अन्येतु शब्दलाघवमिति ।** इदमेव भाष्यस्वरससिद्धं मतम्, एकस्यैवार्थस्य प्रतिपादनाय वृत्तिद्वयापेक्षायां गरीयान् शब्दो बोधको बहुव्रीहौ त्वल्प इति भावः ॥ **न प्रसञ्जनीयमिति ।** अत इष्टिरित्येव सम्यक् ॥ एवं च **'यदीष्टिः पठ्यते नार्थोऽनेन'** इत्यादिः **'इत्येव तदा भवति'** इत्यन्तग्रन्थ आचार्यदेशीयस्येति भावः ॥ किंच वक्ष्यमाणयुक्तिभिः सर्वधनीत्यादिप्रयोगसाधनेऽप्यसुब्वस्त इति **प्रत्ययस्थात्कादितिसूत्र**स्थभाष्यप्रयोगासङ्गतिः, मम तु **सर्वधनाद्यर्थ** इत्यादिशब्दस्य प्रकारार्थत्वान्न दोषः ॥ कर्मधारयपदं च नञ्समासस्याप्युपलक्षणम् ॥ ध्वनितं चेदं **र ऋत** इति सूत्रभाष्ये ॥

(आक्षेपैकदेशिभाष्यम्)

कथं सर्वधनी सर्वबीजी सर्वकेशी नट इति ? ॥

(समाधानैकदेशिभाष्यम्)

***इनिप्रकरणे सर्वादेः* इति वक्ष्यामि । तच्चावश्यं वक्तव्यं ठनो बाधनार्थम् ॥**

(प्रदीपः) **सर्वादेरिति** । ततश्चात्र वचनाल्लाघवं नाश्रीयत इति कर्मधारये कृते इनिः कर्तव्य इत्यर्थः ॥ **ठनो बाधनार्थमिति** । योपीष्टिमारभते तेनापि कर्मधारयाद्धन्याधनायेनिरेवेति वक्तव्यमित्यर्थः ॥

(उद्द्योतः) ततश्चात्र वचनादिति । सर्वादेरिति वचनसामर्थ्यात् ॥

(आक्षेपैकदेशिभाष्यम्)

कथम्—गौरखरवदरण्यम् गौरमृगवदरण्यम् कृष्णसर्पवान् वल्मीकः लोहितशालिमान् ग्रामः ?॥

(समाधानैकदेशिभाष्यम्)

अस्त्यत्र विशेषः । जात्यात्राभिसंबन्धः क्रियते, कृष्णसर्पो नाम सर्पजातिः, सास्मिन् वल्मीकेस्ति ॥ यदा ह्यन्तरेण जातिं तद्वत्ताभिसंबन्धः क्रियते, कृष्णसर्पो वल्मीक इत्येव तदा भवति ॥

(प्रदीपः) **जात्यात्रेति** । जातिश्चाकृते कर्मधारये न प्रतीयते ॥ **यदा हीति** । विशिष्टगुणेन द्रव्येण तद्वत्तायां विवक्षितायामित्यर्थः ॥

(उद्द्योतः) भाष्ये—**कृष्णसर्पो नाम जातिरिति** । जातिव्यक्त्योरभेदाश्रयेणैतदुक्तम् ॥

(पूर्वपदार्थातिशयविवक्षायामप्यातिशायिकप्रत्ययाद्बहुव्रीहेर्बलवत्त्वाधिकरणम्)

(१३३७ पूर्वपदातिशयआतिशायिकव्यवस्थावार्तिकम् ॥ ४॥)

॥ * ॥ पूर्वपदातिशये आतिशायिकाद् बहुव्रीहिः सूक्ष्मवस्त्रतराद्यर्थः ॥ * ॥

(भाष्यम्) **पूर्वपदातिशयविवक्षायामातिशायिकाद् बहुव्रीहिर्भवति विप्रतिषेधेन ॥ किं प्रयोजनम् ? । सूक्ष्मवस्त्रतराद्यर्थः ॥ आतिशायिकस्यावकाशः—पटुतरः पटुतमः । बहुव्रीहेरवकाशः—चित्रगुः शबलगुः । इहोभयं प्राप्नोति—सूक्ष्मवस्त्रतरः । तीक्ष्णशृङ्गतरः । बहुव्रीहिर्भवति विप्रतिषेधेन ॥**

(प्रदीपः) **पूर्वपदातिशय इति** । अतिशयेन सूक्ष्माणि वस्त्राण्यस्येत्यर्थविवक्षायामुभयप्रसङ्गे पूर्वं बहुव्रीहिरिष्यते ततो बहुव्रीहेः प्रत्ययः ॥ भाष्यकारस्तु विप्रतिषेधं प्रत्यासत्त्या पूर्ववदुपन्यस्य सामर्थ्याश्रयेण दूषयित्वेष्टित्वं स्थापयिष्यति ॥

(उद्द्योतः) भाष्ये—**पूर्वपदातिशय इति** । तदर्थातिशये इत्यर्थः ॥

(विप्रतिषेधबाधकभाष्यम्)

नैष युक्तो विप्रतिषेधः । "विप्रतिषेधे परम्" इत्युच्यते । पूर्वश्च बहुव्रीहिः, पर आतिशायिकः ॥

(वार्तिकाशयान्तरभाष्यम्)

इष्टवाची परशब्दः—विप्रतिषेधे परं यदिष्टं तद्भवतीति ॥

(अनुपपत्तिभाष्यम्)

एवमप्ययुक्तः । अन्तरङ्ग आतिशायिकः ॥ कान्तरङ्गता ? । ङ्याप्प्रातिपदिकादातिशायिकः । सुबन्तानां बहुव्रीहिः ॥

(प्रदीपः) **ङ्याप्प्रातिपदिकादिति** ॥ ननु प्रकर्षे आतिशायिकः, प्रकर्षश्च समासार्थस्य भवति । ततश्च पदादेवोत्पत्तव्यम् ॥ एवं तर्ह्यधिकारमात्रमाश्रित्यैवमुक्तम् । अत एवोच्यते—समर्थादिति ॥

(उद्द्योतः) **समासार्थस्य** लिङ्गसंख्याद्याकाङ्क्षारहितस्य ॥ **समर्थादिति** । समर्थः पदविधिरित्युक्तेरिति भावः ॥

(अनुपपत्तिबाधकभाष्यम्)

आतिशायिकोपि नान्तरङ्गः ॥ कथम् ? । समर्थात्तद्धित उत्पद्यते । सामर्थ्यं च सुबन्तेन ॥

(प्रदीपः) **सुबन्तेनेति** । हेतौ तृतीया । सुबन्तेन पदेन प्रकर्षानुभवविषयं सामर्थ्यमर्थस्य नान्यथेत्यर्थः ॥

(उद्द्योतः) **सुबन्तेन पदेनेति** । तेन हेतुना लिङ्गसंख्यादिभिः परिसमाप्तस्यार्थस्य प्रकर्षादिसंबन्धसामर्थ्यमिति भावः ॥ **नान्यथेति** । केवलप्रातिपदिकोपस्थाप्येनेत्यर्थः ॥

(अनुपपत्तिसाधकभाष्यम्)

एवमप्यन्तरङ्गः ॥ कथम् ? । स्वपदार्थे आतिशायिकः । अन्यपदार्थे बहुव्रीहिः ॥

(अनुपपत्तिबाधकभाष्यम्)

एवमपि नान्तरङ्गः ॥ कथम् ? । स्पर्धायामातिशायिको भवति । न चान्तरेण प्रतियोगिनं स्पर्धा भवति ॥

(अनुपपत्तिप्राप्त्यभावभाष्यम्)

नैव वात्रातिशायिकः प्राप्नोति ॥ किं कारणम् ? । असामर्थ्यात् ॥ कथमसामर्थ्यम् ? । सापेक्षमसमर्थं भवतीति । यावता वस्त्राणि तद्वन्तमपेक्षन्ते । तद्वन्तं चापेक्ष्य वस्त्राणां वस्त्रैर्युगपत्स्पर्धा भवति ॥

(प्रदीपः) आतिशायिकस्य प्रतियोगिवस्त्वन्तरापेक्षया

बहुव्रीहिणा साम्यं प्रतिपाद्य सर्वथानुत्पत्तिं प्रतिपादयितुमाह—**नैवेति** । **तद्वन्तमिति** । वस्त्रस्वामिनमित्यर्थः । अस्यातिशयेन सूक्ष्माणि वस्त्राणीति तद्वतोपेक्षणात् ॥

(उद्द्योतः) प्रतियोगिवस्त्वन्तरापेक्षयेति । हेतौ तृतीयेयम् ॥ **तद्वतोपेक्षणादिति** । वस्त्राणि सौक्ष्मविषयस्पर्द्धायां तद्वन्तमपेक्षन्त इति भाष्याक्षरार्थः । बहुव्रीह्यातिशायिकयोर्युगपत्प्राप्तिविषये तद्वन्तमपेक्ष्य वस्त्राणां सौक्ष्म्यगुणविषया स्पर्धोदेति । अस्यापि सूक्ष्माणि वस्त्राण्यस्यापि सूक्ष्माणि अस्यास्मादतिशयेन सूक्ष्माणीति विवक्षायां किलातिशायिकबहुव्रीह्योरेकत्र प्रसक्तिर्वाच्या । तत्र पक्षद्वारा सूक्ष्मशब्दस्य तद्वत्सापेक्षत्वादातिशायिकाप्रसक्तिरित्ययुक्तो विप्रतिषेध इति भावः । एवं च परम्परया सौक्ष्म्यगुणविषयप्रकर्षस्य विशेषणस्यैव सापेक्षत्वमित्युक्तं भवति ॥

(आक्षेपभाष्यम्)

ननु चायमातिशायिक एवमात्मकः सत्यां व्यपेक्षायां विधीयते ॥

(प्रदीपः) **सत्यामिति** । ततश्च यथा प्रतियोग्यपेक्षायां प्रत्ययो भवत्येवं तद्वदपेक्षायामपि कस्मान्न भवतीति भावः ॥

(उद्द्योतः) वचनप्रामाण्यादातिशायिकस्तत्र भविष्यत्येवेति मन्यमानः शङ्कते—भाष्ये—**ननु चेति** ॥

(समाधानभाष्यम्)

सत्यमेवमात्मकः । यां च नान्तरेण व्यपेक्षामातिशायिकस्य प्रवृत्तिस्तस्यां सत्यां भवितव्यम् ॥ कां च नान्तरेण व्यपेक्षामातिशायिकस्य प्रवृत्तिः?। या हि प्रतियोगिनं प्रति व्यपेक्षा ॥ या हि तद्वन्तं प्रति, न तस्यां भवितव्यम् ॥

(उद्द्योतः) **या हि तद्वन्तमिति** । न सा नियतेति भावः । एकस्वामिकयोरपि स्पर्द्धादर्शनादिति बोध्यम् ॥

(आक्षेपभाष्यम्)

बहुव्रीहिरपि तर्हि न प्राप्नोति ॥ किं कारणम्?। असामर्थ्यादेव ॥ कथमसामर्थ्यम्?। सापेक्षमसमर्थं भवतीति । यावता वस्त्राणि वस्त्रान्तराण्यपेक्षन्ते तद्वता चाभिसंबन्धः ॥

(प्रदीपः) **वस्त्राणीति** । अतिशयनानि वस्त्राण्यतिशय्यमानानि वस्त्राण्यपेक्षन्त इत्यर्थः ॥

(उद्द्योतः) **अतिशयनानीति** । अन्याभिभवकर्तॄणि प्रकर्षयुक्तानीत्यर्थः ॥ **अतिशय्यमानानि** । अभिभूयमानानीत्यर्थः । अतिशेतिरभिभवे ॥ भाष्ये—**तद्वता च सम्बन्ध** इत्यनेन हि प्रकृते विशेषणस्य सापेक्षस्वरूपं तरपोप्राप्तिबीजं सूचितम् ॥

(समाधानभाष्यम्)

एवं तर्हि नेदं तस्य योगस्योदाहरणं 'विप्रतिषेधे परम्' इति ॥ किं तर्हि?। इष्टिरियं पठिता *पूर्वपदातिशये आतिशायिकाद् बहुव्रीहिरिष्टः सूक्ष्मवस्त्रतराद्यर्थः * इति ।

(प्रदीपः) एवं सापेक्षत्वाद्द्वयोरपि निराकृतयोरर्थान्तरत्वमाह—**एवन्तर्हीति** ॥

(उद्द्योतः) **अर्थान्तरत्वं**, इष्टिरूपत्वम् । क्वचित्त्वर्थत्वमिति पाठस्तत्राप्ययमेवार्थः ॥ भाष्ये—**किं तर्हीति** । एवं च तत्सामर्थ्यात्सापेक्षत्वेपि बहुव्रीहितद्धिताविति भावः ॥

(वार्तिकानावश्यकताभाष्यम्)

यदीष्टिरियं पठिता, नार्थोऽनेन ॥

(प्रदीपः) **नार्थोऽनेनेति** । इष्ट्या विनाप्यस्यार्थस्य सिद्धत्वादिति भावः ॥

(आक्षेपभाष्यम्)

कथं येषा युक्तिरुक्ता—वस्त्रान्तराणां च वस्त्रान्तरैर्युगपत्स्पर्द्धा तद्वता चाभिसंबन्धः—इति ।

(प्रदीपः) **येषा युक्तिरुक्तेति** । सा नाश्रीयत इत्यर्थः ॥

(उद्द्योतः) **कथमिति** । वस्त्रान्तराणां वस्त्रान्तरैर्युगपत्स्पर्धा तद्वता चाभिसम्बन्ध इति येयं बहुव्रीहितद्धितयोरप्राप्त्युपपादिका युक्तिरुक्ता तया युक्त्या द्वयोरप्यप्राप्तेः कथमानर्थक्यमिति प्रश्नः ॥

(समाधानभाष्यम्)

यदा ह्यन्तरेण वस्त्राणां वस्त्रान्तरैर्युगपत्स्पर्द्धां तद्वताभिसंबन्धः क्रियते । निष्प्रतिद्वन्द्वस्तदा बहुव्रीहिः । बहुव्रीहेरातिशायिकः ॥

(प्रदीपः) कथं तर्ह्याश्रीयत इत्याह—**यदा हीति** । अन्यपदार्थमात्रविवक्षायां बहुव्रीहौ कृते पश्चादातिशायिकः क्रियते । अतिशयमात्रविवक्षायां तु प्रत्यये कृते पश्चाद् बहुव्रीहिस्ततश्च सूक्ष्मतरवस्त्र इत्यपि सिध्यति । इष्टौ तु सत्यामेतन्न सिध्येत् ॥

(उद्द्योतः) समाधत्ते, **यदाहीती**त्यन्ये । यदा ह्यन्तरेण वस्त्राणां वस्त्रैर्युगपत्स्पर्धामिति पाठः । **तद्वताभिसम्बन्ध** इति च ॥ **इष्टौ तु सत्यामिति** । तस्यादिष्टिर्दुष्टेति भाष्याभिप्राय इति भावः ॥

(आक्षेपभाष्यम्)

न तर्हीदानीमिदं भवति—सूक्ष्मतरवस्त्र इति? ॥

(उद्द्योतः) **तर्हीदानीमिति** । तदेदानीमित्यर्थः । इष्ट्यारम्भ इति यावत् । **इदं न भवति** । इदं न सिध्यति ॥

(समाधानभाष्यम्)

भवति, यदान्तरेण तद्वन्तं वस्त्राणां वस्त्रान्तरैर्युगपत्स्पर्द्धा भवति । निष्प्रतिद्वन्द्वस्तदातिशायिकः ॥

(उद्द्योतः) **भवति** । सिध्यति ॥ कुतस्तत्राह—**यदेति** । इति भाष्याक्षरार्थः ॥

(समाधानबाधकाक्षेपभाष्यम्)

कथं पुनरन्यस्य प्रकर्षेणान्यस्य प्रकर्षः स्यात्?॥

(प्रदीपः) यदुक्तं बहुव्रीहौ कृते पश्चादातिशायिकः क्रियत इति, तत्राह—**कथं पुनरिति** । अतिशयेन सूक्ष्मवस्त्र इति बहुव्रीहेः प्रत्यये क्रियमाणे वस्त्रगतसौक्ष्म्यप्रकर्षे कथमन्यपदार्थप्रकर्षः स्यादित्यर्थः ॥

(उद्द्योतः) **कथमन्यपदार्थस्य प्रकर्ष इति** । यतः प्रत्ययस्तदर्थप्रकर्षस्तत्प्रत्ययनिमित्तम् । एवं च सौक्ष्म्यप्रकर्षे प्रत्यये क्रियमाणेप्यन्यपदार्थप्रकर्षाभावात्कथं तत्प्रतिपादकसमुदायात् प्रत्ययः । प्रकर्षद्वयप्रतिपादने तु नैकस्य सामर्थ्यम् । न च सौक्ष्म्यप्रकर्ष एवान्यपदार्थप्रकर्षः, अन्यदीयस्यान्यदीयत्वायोगादिति भावः ॥

(समाधानसाधकभाष्यम्)

नैवान्यस्य प्रकर्षेणान्यप्रकर्षेण भवितव्यम् । यथैवायं द्रव्येषु यतते—वस्त्राणि मे स्युरिति । एवं गुणेष्वपि यतते—सूक्ष्मतराणि मे स्युरिति ॥

(प्रदीपः) अत्रोत्तरम्—**नैवान्यस्येति** । सर्वत्रैव यतः प्रत्ययो विधीयते तदर्थस्य स्वतः प्रकर्षाभावादन्यगत एव प्रकर्ष आश्रीयते । यथोक्तम्—

द्रव्यस्याव्यपदेश्यस्य य उपादीयते गुणः ।
भेदको व्यपदेशाय तत्प्रकर्षोऽभिधीयते ॥

इति ॥ एक एवासौ प्रकर्ष इत्यर्थः । यद्यप्यत्राश्रयान्तरवर्तिगुणप्रकर्षस्तथापि यत्र यथाभूतः संभवति तत्र तथाभूत आश्रीयते ॥

(उद्द्योतः) **एक एवासाविति** । गुणप्रकर्ष एव द्रव्यप्रकर्ष इत्यर्थः । स च कश्चित्प्रवृत्तिनिमित्तगुणप्रकर्षः, यथा—शुक्लतर इत्यादौ । कश्चित्तत्सहचरितगुणप्रकर्षो यथा—गोतर इत्यादौ । कश्चित्तद्विशेषणघटकगुणप्रकर्षो यथा—प्रकृते ॥ **नैवान्यस्येति** भाष्येणापि पृथग् द्रव्यप्रकर्षाभाव एव प्रतिपाद्यते इति बोध्यम् ॥ भाष्ये—**वस्त्राणि मे स्युरिति** । वस्त्रस्य द्रव्यत्वात्तत्र प्रकर्षाभावेन तरप् न कृतः ॥ **सूक्ष्मतराणीति** । सूक्ष्मत्वस्य गुणत्वात्तत्र प्रकर्षसम्भवेन बहुव्रीहेरुत्पन्नेनाप्यातिशायिकेन परम्परासम्बद्धस्य तस्यैव प्रकर्ष उच्यत इति भावः ॥ **तथापि यत्रेति** । साक्षात्स्वगतगुणप्रकर्षः स्वसम्बन्धिपदार्थगतगुणप्रकर्षो वा उभयमपि द्रव्यप्रकर्षरूपं भवत्येवेति भावः ॥

(समाधानबाधकभाष्यम्)

नात्रातिशायिकः प्राप्नोति । किं कारणम्? । गुणवचनादित्युच्यते । न च समासो गुणवचनः ॥

(प्रदीपः) **गुणवचनादिति** । नात्राजादी गुणवचनादेवेति बोद्धव्यं, तरपोत्र प्रकृतत्वात् ॥ तस्माद् गुणस्यैव प्रकर्षः संभवति न द्रव्यस्येत्याश्रित्यैतदुक्तम् ॥

(उद्द्योतः) भाष्ये—**गुणवचनादिति** । गुणोपसर्जनगुणिबोधकात्प्रवृत्तिनिमित्तगुणप्रकर्षे तत्सहचरितगुणप्रकर्षे वा प्रत्यय उच्यत इत्यर्थः । गुणग्रहणं धर्ममात्रपरम् ॥

(समाधानसाधकभाष्यम्)

समासोपि गुणवचनः । कथम्? । अजहत्स्वार्था वृत्तिरिति ॥

(प्रदीपः) **अजहत्स्वार्थेति** । तत्र सूक्ष्मार्थस्य विद्यमानत्वात् प्रकर्षसंभवः ॥

(उद्द्योतः) **समासोपि गुणवचन इति** । सूक्ष्मत्वविशिष्टवस्त्रविशिष्टपुरुषवचनत्वादिति भावः ॥ अन्यपदार्थे रूढतया गुणवचनत्वं नेत्याशयेन पृच्छति—**कथमिति** ॥ उत्तरयति—**अजहत्स्वार्थेति** । एवं चावयवार्थोपस्कृतान्यपदार्थस्य समुदायेनोपस्थापनाद् गुणवचनत्वम् । प्रवृत्तिनिमित्तसहचरितगुणप्रकर्षश्च प्रवृत्तिनिमित्तविशेषणविशेषणगुणप्रकर्षोपि तदुत्पत्तिनिमित्तम् । स च गोतर इत्यादाववाच्यगतोपि यदि निमित्तं किं वक्तव्यं विशेषणविशेषणतया वाच्यस्येति भावः ॥

(आक्षेपभाष्यम्)

अथ जहत्स्वार्थायां तु दोष एव? ॥

(उद्द्योतः) **अथेति** । तत्र हि उपसर्जनपदानामर्थाभावेपि प्रधानपदेन समुदायेन वस्तुतस्तादृशगुणोपलक्षितव्यक्तेरेव बोधो न तु गुणानां वाच्यत्वमिति भावः ॥

(समाधानभाष्यम्)

जहत्स्वार्थायां च न दोषः । भवति बहुव्रीहौ तद्गुणसंविज्ञानमपि । तद्यथा—'शुक्लवाससमानय' 'लोहितोष्णीषाः प्रचरन्तीति तद्गुण आनीयते तद्गुणाश्च प्रचरन्ति ॥

(उद्द्योतः) **जहत्स्वार्थायां च न दोष इति** । अवयवानामर्थाभावेपि तद्गुणविशिष्टाया व्यक्तेरानयनादि यथाऽवाच्यत्वेपि, तथा तद्गतप्रकर्षे प्रत्ययः गोतर इत्यादाववाच्यवाहदोहादिप्रकर्ष इवेति भावः ॥

(उत्तरपदातिशय आतिशायिकव्यवस्थाधिकरणम्)

(१३३८ आक्षेपवार्त्तिकम् ॥ ५ ॥)

॥ * ॥ उत्तरपदातिशये आतिशायिको बहुव्रीहेः बह्वाढ्यतराद्यर्थः ॥ * ॥

(भाष्यम्) **उत्तरपदातिशये आतिशायिको बहुव्रीहेर्भवति विप्रतिषेधेन ॥ किं प्रयोजनम्? । बह्वाढ्यतराद्यर्थः । बह्वाढ्यतरः । बहुसुकुमारतरः ॥ कः पुनरत्र विशेषः—बहुव्रीहेर्वातिशायिकः स्याद्, आतिशायिकान्तेन वा बहुव्रीहिः? ॥ स्वरकपोर्विशेषः । यद्यत्रातिशायिकाद्बहुव्रीहिः स्यात्—बह्वाढ्यतर एवं स्वरः प्रसज्येत, बह्वाढ्यतर इति चेष्यते । बह्वाढ्यकतर इति च प्राप्नोति, बह्वाढ्यतरक इति चेष्यते ॥**

(प्रदीपः) बह्वाढ्यतर इति। यद्यत्र बहुव्रीहिं कृत्वा आतिशायिकः क्रियते तदा बहोर्नञ्वदुत्तरपदभूम्नीत्यन्तोदात्तत्वमाढ्यशब्दाकारस्य स्याद्, रेफाकारस्य चेष्यते। अयमर्थो न्यायसिद्धो यदि समासात् प्रकर्षप्रत्यय उत्पद्यते तदा किं बहुत्वगुणाश्रयः प्रकर्ष उत आढ्यत्वाश्रयः प्रत्ययोत्पत्तिनिमित्तमिति संदेहः स्यात्। तस्मात् पूर्वं प्रकर्षस्य विवक्षा पश्चादन्यपदार्थस्य॥

(उद्द्योतः) सन्देहः स्यादिति। प्रकरणादिना निश्चयसम्भवादिदं चिन्त्यम्॥

(१३३९ उत्तरपदलोपविधायकवार्तिकम्॥ ६॥)

॥ * ॥ समानाधिकरणाधिकारे शाकपार्थिवादीनामुपसंख्यानमुत्तरपदलोपश्च ॥ * ॥

(भाष्यम्) समानाधिकरणाधिकारे शाकपार्थिवादीनामुपसंख्यानं कर्तव्यम्। उत्तरपदलोपश्च वक्तव्यः। शाकभोजी पार्थिवः शाकपार्थिवः। कुतपवासाः सौश्रुतः कुतपसौश्रुतः। अजापण्यस्तौल्वलिरजातौल्वलिः। यष्टिप्रधानो मौद्गल्यः यष्टिमौद्गल्यः॥ वर्णो वर्णेन॥ ६८॥

(प्रदीपः) शाकभोजीति। शाकभोजित्वात्तत्साहचर्यात्तद्व्यपदेशात्रार्थं उत्तरपदलोपेनेत्याहुः॥ ६८॥

(उद्द्योतः) नार्थं उत्तरपदलोपेनेत्याहुरिति। अत्रारुचिबीजं तु शाकभोजिपार्थिव इत्यादिप्रयोगव्यावृत्तये वार्तिकमावश्यकमिति॥ ६८॥

(२६५ तत्पुरुषसंज्ञासूत्रम्॥ २।१।३ आ. १२॥)

४१९ चतुष्पादो गर्भिण्या॥ २।१।७०॥

(१३४० वार्तिकम्॥ १॥)

॥ * ॥ चतुष्पाज्जातिः ॥ * ॥

(व्याख्याभाष्यम्)

चतुष्पाज्जातिरिति वक्तव्यम्। इह मा भूत्—कालाक्षी गर्भिणी। स्वस्तिमती गर्भिणी॥ चतुष्पादो गर्भिण्या॥ ७०॥

(प्रदीपः) चतुष्पादो॥७०॥ चतुष्पाज्जातिरिति। केचिज्जातिग्रहणमनुवर्त्यमित्याहुः॥ अन्ये त्वाहुः—शब्दान्तरसन्निधिनिरपेक्षा ये चतुष्पाज्जातिवचनास्त एवान्तरङ्गत्वाद् गृह्यन्ते न तु कालाक्ष्यादयो यौगिकाः शब्दान्तरसन्निधानापेक्षचतुष्पाज्जातिविषयाः॥ ७०॥

(उद्द्योतः) चतुष्पादो॥ ७०॥ भाष्ये—वक्तव्यमित्यस्य व्याख्येयमित्यर्थः। व्याख्यानप्रकारं दर्शयति—केचिदित्यादिना। शब्दान्तरेति। चतुष्पाद्वचनाश्चतुष्पाद्विषया इत्येव पाठः॥ जातिरित्यस्य विच्छिन्नत्वादन्तरङ्गबहिरङ्गभावस्य च सर्वैर्दुर्ज्ञेयत्वाद्वचनमेवावश्यकमिति तत्त्वम्॥ ७०॥

(२६६ तत्पुरुषसंज्ञासूत्रम्॥ २।१।३ आ. १३॥)

४२० मयूरव्यंसकादयश्च॥ २।१।७१॥

(आक्षेपभाष्यम्)

किमर्थश्चकारः?॥

(समाधानभाष्यम्)

एवकारार्थः। मयूरव्यंसकादय एव। क्व मा भूत्?। परमो मयूरव्यंसक इति॥ मयूरव्यंसकादयश्च॥ ७१॥

इति श्रीमद्भगवत्पतञ्जलिविरचिते व्याकरणमहाभाष्ये द्वितीयस्याध्यायस्य प्रथमे पादे तृतीयमाह्निकम्॥

पादश्च समाप्तः॥

(प्रदीपः) मयूर॥ ७१॥ मयूर इव व्यंसको धूर्तः छात्र इव व्यंसकः काम्बोज इव मुण्ड इत्युपमानसमासापवादोऽयं समासः प्रतिपदविहितोपमानसमासविषयपूर्वपदप्रकृतिस्वरबाधनार्थं इत्याहुः॥ ७१॥

इत्युपाध्यायजैयटपुत्रकैयटकृते महाभाष्यप्रदीपे द्वितीयाध्यायस्य प्रथमपादे तृतीयमाह्निकम्॥ पादश्च समाप्तः॥

(उद्द्योतः) मयूर॥ ७१॥ मयूरइव व्यंसक इति। केचित्तु विशेषणसमासे गुणवचनत्वाद्व्यंसकस्य पूर्वनिपाते प्राप्ते इदमित्याहुः। तत्र। उपमानानीति सूत्रस्थभाष्यकैयटरीत्या तस्य येन नाप्राप्तिन्यायेन विशेषणसमासबाधकत्वात्॥ ७१॥

इति शिवभट्टसुतसतीगर्भजनागोजीभट्टकृते भाष्यप्रदीपोद्द्योते द्वितीयाध्यायस्य प्रथमे पादे तृतीयमाह्निकं, पादश्च समाप्तः॥ १॥

द्वितीयपादादिद्वितीयाध्य

(तत्पुरुषप्रकरण एकदेशिसमासप्रकरणम्)

(२६७ तत्पुरुषसंज्ञासूत्रम् ॥ २।२।१ आ. १)

४२२ अर्द्धं नपुंसकम् ॥ २।२।२ ॥

(अनिष्टापत्तिनिराकरणाधिकरणम्)

(आक्षेपभाष्यम्)

इह कस्मान्न भवति-ग्रामार्द्धो नगरार्द्ध इति ? ॥

(प्रदीपः) **अर्द्धम्** ॥ २ ॥ नपुंसकस्याव्यवस्थितत्वात् कृते च समासे पूर्वपदार्थस्य लिङ्गविशेषानवधारणात् कृतमपि नपुंसकग्रहणमकृतसममिति मत्वा पृच्छति—**इहेति** ॥

(उद्द्योतः) **अर्धम्** ॥ २ ॥ सूत्रे **नपुंसकमित्युक्तेरिह कस्मा**-दितिप्रश्नोनुपपन्न इत्याशङ्क्याह—**नपुंसकस्येति** ॥ सूत्रे नपुंसकग्रहणं किमर्धशब्दस्यार्थविशेषप्रतिपत्तये, उत समासगतरूपविशेषप्रतिपत्तये, नाद्य इत्याह—**अव्यवस्थितत्वादिति** । नपुंसकत्वस्यापूपार्धमित्यादावन्यार्थेपि दर्शनादिति भावः ॥ नान्त्य इत्याह—**कृते चेति** । तस्य नपुंसकत्वलक्षणविशेषानवसायेन तत्कृतरूपविशेषाभावादिति भावः ॥

(समाधानभाष्यम्)

अर्द्धशब्दस्येदं नपुंसकलिङ्गस्य ग्रहणम् । पुल्लिङ्गश्चात्रार्धशब्दः ॥

(आक्षेपभाष्यम्)

क्व पुनरयं नपुंसकलिङ्गः, क्व पुल्लिङ्गः ? ॥

(प्रदीपः) **क्व पुनरिति** । नपुंसकत्वावधारणहेतावर्थे प्रश्नः ॥

(उद्द्योतः) अधिकरणस्याकाशस्य निर्ज्ञातत्वात्प्रश्नानुपपत्तेराह—**नपुंसकस्येति** । कस्मिन्नर्थे पुंस्त्ववाचक इति भाष्याक्षरार्थः ॥

(समाधानभाष्यम्)

समप्रविभागे नपुंसकलिङ्गः, अवयववाची पुल्लिङ्गः ॥

(प्रदीपः) **अवयववाची पुल्लिङ्ग इति** । नियमेन नपुंसकलिङ्गो न भवतीत्येवंपरमेतद् । अवयववाची त्वभिधेयवशाद् सर्वलिङ्गस्तथा च प्रयोगो दृश्यते अपूपार्द्धं मया भक्षितं दन्तार्द्धमास्यात् पतितमिति । तदत्र नपुंसकग्रहणाद् यस्मिन्नर्थविशेषे नियमेन नपुंसकत्वं तदर्थवृत्तिरेवार्द्धशब्द आश्रीयते तत्रैवार्थे नपुंसकत्वस्याव्यभिचारात् । **अर्द्धमिति** निर्देशादेव नपुंसकत्वे लब्धे नपुंसकग्रहणं ज्ञापकं निर्देशेषु लिङ्गाविवक्षायाः ॥

(उद्द्योतः) पुल्लिङ्ग एवेति भ्रमं वारयति—**नियमेनेति** ॥ **नपुंसकग्रहणं ज्ञापकमिति** । निर्देशेन नपुंसकत्वमात्रे लब्धेपि नित्यनपुंसकत्वलाभाय तस्यावश्यकत्वम् । अन्यथा अपूपार्धं दन्तार्धमित्यादावसमांशवाचिन्यपि एकदेशिसमासः स्यादिति चिन्त्यमेतत् ॥ परे तु **समप्रविभागे नपुंसकलिङ्ग** इत्यस्य नपुंसकलिङ्गोपीत्यर्थः । अत एवै**ओङेच इगिति** सूत्रयोर्भाष्ये एचो ह्रस्वविधानेऽर्धैकारार्धौकारौ प्राप्नुत इति शङ्कायां **नैव लोके नापि वेदेर्ध एकारोर्ध ओकारो** वास्तीत्युत्तरपरभाष्ये समविभागविषयेपि पुल्लिङ्गः प्रयुक्तः । अवयववाची तु पुल्लिङ्ग एव ॥ **अपूपार्धमिति** समप्रविभाग एव । अन्यत्रापूपार्ध इत्येव ॥ **परवल्लिङ्गमिति** सूत्रे भाष्येप्येतत्स्पष्टमित्युत्तरसूत्रे स्फुटीकरिष्यते ॥ अन्यतरस्यांग्रहणापकर्षेण योगविभागेन वा एकदेशिसमासविषये षष्ठीसमासः सूत्रकृतोपीष्ट एव । एवं चारम्भप्रत्याख्यानयोः समफलता । नपुंसकग्रहणं तु सूत्रेषु निर्देशे लिङ्गाविवक्षायां ज्ञापकमित्याहुः ॥

(आक्षेपभाष्यम्)

इह कस्मान्न भवति—अर्द्धं पिप्पलीनामिति ? ॥

(उद्द्योतः) भाष्ये—**अर्धपिप्पलीनामिति** । दशानां पिप्पलीनामर्धमित्यर्थः । न च समासे एकत्वसंख्यायां औत्सर्गिकत्वात्कथमत्र समासापादनं एकत्वस्यापि तत्राभानाच्छुद्धपिप्पलीत्वेनानेकपिप्पलीबोधसम्भव इति शङ्काशयः ॥

(प्रत्याक्षेपभाष्यम्)

न वा भवति—अर्द्धपिप्पल्य इति ? ॥

(उद्द्योतः) इतरोर्धपदार्थस्य तत्र पञ्चपिप्पलीरूपत्वेन समासे बहुवचनं मत्वा पृच्छति—**न वा भवतीति** ॥

(प्रत्याक्षेपसमाधानभाष्यम्)

भवति, यदा खण्डसमुच्चयः—अर्द्धपिप्पली चार्द्धपिप्पली चार्धपिप्पली चार्द्धपिप्पल्य इति । यदा त्वेतद्वाक्यं भवति—अर्द्धं पिप्पलीनामिति, तदा न भवितव्यम् ॥

(प्रदीपः) **यदा त्वेतदिति** । अर्थश्चात्र भिद्यत एव । समासे च कृते अर्द्धपिप्पलीत्येव स्यात् पूर्वपदार्थस्य प्राधान्यात्तस्य चैकत्वात् ॥

(उद्द्योतः) अर्थान्तरे भवति न त्वेतदर्थे इत्याह परः—**भवति यदेत्यादिना** ॥ **अर्थश्चात्रेति** । दशानां पिप्पलीनामर्धं पञ्चेत्यत्रार्थः, पिप्पलीनां प्रत्येकमर्धानि बहूनीति तत्रार्थः । भाष्ये—**तदा न भवितव्यमित्यस्य** 'अनेन रूपेण न भवितव्यम्' इत्यर्थमभिप्रेत्याह—**अर्धपिप्पलीत्येव स्यादिति** । यद्यप्यर्धपदार्था बहवः तथाप्यर्धशब्देनैकत्वावच्छिन्नसमुदायस्यैव भानादिति भावः ॥

(आक्षेपकारणभाष्यम्)

तदा कस्मान्न भवति ? ॥

(उद्द्योतः) तदा कस्मान्नेति । समासः कुतो नेत्यर्थः ॥

(समाधानभाष्यम्)

एकाधिकरण इति वर्तते ॥

(आक्षेपभाष्यम्)

न तर्हीदानीमिदं भवति—अर्द्धराशिरिति ? ॥

(प्रदीपः) अर्द्धराशिरिति । राशेरवयवव्यतिरेकेणाभावादवयवानां च बहुत्वादेकत्वाभावं मन्यते ॥

(समाधानभाष्यम्)

भवति । एकमेवेदमधिकरणं योसौ राशिर्नाम ॥ अर्धं नपुंसकम् ॥ २ ॥

(प्रदीपः) एकमेवेति । शब्ददेकस्यैवार्थस्य तिरोहितभेदस्यावगमात् ॥ २ ॥

(उद्द्योतः) तिरोहितभेदस्येति । तिरोहितावयवभेदस्येत्यर्थः । समूहः समूहिभ्यो भिन्नोपीति भावः ॥ २ ॥

(२६८ एकदेशितत्पुरुषसंज्ञासूत्रम् ॥ २। २।१ आ. २ ॥)

४२३ द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम् ॥ २।२।३ ॥

(अन्यतरस्यांग्रहणप्रयोजनाधिकरणम्)

(आक्षेपभाष्यम्)

अन्यतरस्यांग्रहणं किमर्थम् ? ॥

(प्रदीपः) द्वितीय ॥ ३ ॥ अन्यतरस्यांग्रहणस्य पक्षे षष्ठीसमासप्राप्तये कृतस्य ज्ञापकत्वं नान्तरीयकतया प्रतिपादयितुं पूर्वपक्षोपन्यासः ॥ यद्यपि पारे इत्यत्रायमर्थो ज्ञापितस्तथापीह स्मरणाय पुनर्ज्ञाप्यते ॥

(उद्द्योतः) द्वितीयतृ ॥ ३ ॥ नान्तरीयकतयेति । तत्सिद्ध्यनुगुणतया ज्ञापकत्वमस्येति भावः ॥ स्मरणाय पुनर्ज्ञाप्यते इति । वारद्वयज्ञापितं दृढसंस्कारजननद्वारा शीघ्रं स्मरणायेत्यर्थः । विनिगमनाविरहादिदमपि ज्ञापकमिति भावः ॥

(आक्षेपबाधकभाष्यम्)

अन्यतरस्यां समासो यथा स्यात्—समासेन मुक्ते वाक्यमपि यथा स्याद्—द्वितीयं भिक्षाया इति ॥

(आक्षेपसाधकभाष्यम्)

नैतदस्ति प्रयोजनम् । प्रकृता महाविभाषा तया वाक्यमपि भविष्यति ॥

(आक्षेपबाधकप्रयोजनभाष्यम्)

इदं तर्हि प्रयोजनम् । एकदेशिसमासेन मुक्ते षष्ठीसमासो यथा स्यात्—भिक्षाद्वितीयमिति ॥

(आक्षेपबाधकभाष्यम्)

एतदपि नास्ति प्रयोजनम् । अयमपि विभाषा-षष्ठीसमासोपि । तावुभौ वचनाद्भविष्यतः ॥

(समाधानभाष्यम्)

अत उत्तरं पठति—

(१२४१ समाधानवार्तिकम् ॥ १ ॥)

॥ * ॥ द्वितीयादीनां विभाषाप्रकरणे विभाषावचनं ज्ञापकमवयवविधाने सामान्यविधानाभावस्य ॥ * ॥

(व्याख्याभाष्यम्)

द्वितीयादीनां विभाषाप्रकरणे विभाषावचनं क्रियते । ज्ञापनार्थम् । किं ज्ञाप्यते ? । एतज्ज्ञापयत्याचार्यः—अवयवविधौ सामान्यविधिर्न भवतीति । किमेतस्य ज्ञापने प्रयोजनम् ? । भिनत्ति छिनत्तीति श्नमि कृते शप्न भवतीति ॥

(प्रदीपः) अवयवविधान इति । सामान्याश्रयसमूहापेक्षया प्रतिनियतो विशेष एकदेशो भवतीति विशेषविषयं विधानमवयवविधानशब्देनोक्तम् ॥ किमेतस्येति । न्यायादेव विशेषविधिः सामान्यविधेर्बाधक इति मत्वा पृच्छति ॥ भिनत्तीति । विरोधादेकफलत्वाच्च बाध्यबाधकभावः । इह तु भिन्नदेशत्वाद्विरोधाभावो विकरणानां चानर्थक्यादेकफलत्वाभावः । वार्तिककारस्य मतेनेदमुक्तम् । स हि विरोधाभावे बाध्यबाधकभावं नेच्छति । तथा चाह—श्नम्बहुजकश्नु नानादेशत्वादुत्सर्गप्रतिषेधः इति ॥ भाष्यकारस्तु विनापि विरोधेन सामान्यविशेषविध्योर्बाध्यबाधकभावमभ्युपगच्छति । अर्थाभिधाने साहायकप्रतिपत्तौ एकफलताप्यनयोरस्ति ॥

(उद्द्योतः) सक्षाप्येवयवाभावादाह—सामान्याश्रयसमूहेति । षष्ठीत्यादिना सामान्यशास्त्रेण विहितेत्यर्थः ॥ प्रतिनियत इति । अर्धमित्यादिशास्त्रेण विहितः ॥ भाष्ये अवयवविधाविति । तद्विषये नोत्सर्गप्रवृत्तिरित्यर्थः ॥ न्यायादिति । येननाप्राप्तिन्यायादित्यर्थः ॥ विरोधादित्यादि । तदुभयसत्त्वे हि बाध्यबाधकभावः । प्रकृते चोभयोरप्यभावात्तदभाव इति वार्तिकमतेनेदं प्रयोजनमुक्तमित्यन्वयः ॥ भाष्यकारस्त्विति । सत्यपि सम्भवे बाधनं भवतीति तदुक्तेरिति भावः ॥ नन्वीदृशं दधिदानं तक्रदानस्य निवर्तकं दृष्टं तत्र ह्येकफलतास्ति न च सा प्रकृते इत्यत आह—अर्थाभिधाने इति ॥ प्रतिपत्तिः प्राप्तिः । वस्तुतो भाष्यनये विरोधाभाव इवैकफलत्वाभावेपि बाध इति निरूपितमाकडारसूत्रे भाष्ये ॥

(समाधानबाधकभाष्यम्)

नैतदस्ति प्रयोजनम् । शबादेशाः श्नमादयः करिष्यन्ते ॥

(उद्द्योतः) शबादेशाः श्नमादय इति । तत्र श्नमादेशस्थानिवत्त्वाच्छपं निवर्तयति मित्त्वादन्त्यादचः परो रमागमवदिति भावः ॥

(आक्षेपभाष्यम्)

तर्हि शपो ग्रहणं कर्तव्यम् ॥

(आक्षेपबाधकभाष्यम्)

न कर्तव्यम्। प्रकृतमनुवर्तते। क प्रकृतम्?। "कर्तरि शप्" इति ॥

(आक्षेपसाधकभाष्यम्)

तद्वै प्रथमानिर्दिष्टम्। षष्ठीनिर्दिष्टेन चेहार्थः ॥

(आक्षेपबाधकभाष्यम्)

रुधादिभ्य इत्येषा पञ्चमी शबिति प्रथमायाः षष्ठीं प्रकल्पयिष्यति "तस्मादित्युत्तरस्य" इति ॥

(आक्षेपसाधकभाष्यम्)

प्रत्ययविधिरयम्। न च प्रत्ययविधौ पञ्चम्यः प्रकल्पिका भवन्ति ॥

(आक्षेपबाधकभाष्यम्)

नायं प्रत्ययविधिः । विहितः प्रत्ययः प्रकृत एवानुवर्तते ॥

(समाधानसाधकभाष्यम्)

एवं तर्हि ज्ञापयत्याचार्यः 'यत्रोत्सर्गापवादं विभाषा तत्रापवादेन मुक्ते उत्सर्गो न भवति' इति ॥

(उद्द्योतः) भाष्ये—यत्रोत्सर्गापवादमिति । यत्रोत्सर्गापवादं महाविभाषाविकल्पितं तत्रेति पाठान्तरम् ॥

(आक्षेपभाष्यम्)

किमेतस्य ज्ञापने प्रयोजनम्? ॥

(प्रयोजनभाष्यम्)

"दिक्पूर्वपदान् ङीप्" प्राङ्मुखी । प्राङ्मुखा । प्रत्यङ्मुखी। प्रत्यङ्मुखा । ङीपा मुक्ते ङीष् न भवति ॥

(प्रदीपः) प्राङ्मुखीति । अस्वाङ्गपूर्वपदाद्वेत्यतो ङीष्ङीब्विधौ वेत्यनुवृत्तिः ॥

(उद्द्योतः) अस्वाङ्गपूर्वपदाद्वेत्यतो ङीष्ङीब्विधौ चेत्यनुवृत्तिरिति पाठः ॥ उत्सर्गापवादयोरुभयोरपि वैकल्पिकत्वं दर्शयितुं ङीष्ङीब्विधावित्युक्तम् ॥

(प्रयोजनबाधकभाष्यम्)

नैतदस्ति प्रयोजनम्। वक्ष्यत्येतद्—*दिक्पूर्वपदान्ङीषोनुदात्तत्वम्। ङीब्विधाने ह्यन्यत्रापि ङीब्विषयाद् ङीष्प्रसङ्गः* इति ॥

(प्रदीपः) नैतदस्तीति । वार्तिककारस्य मतमाश्रित्य प्रयोजनप्रत्याख्यानम्। यद्यपूर्वो ङीब्विधीयेत तदा प्राग्गुल्फा प्रत्यग्जघनेत्यादावपि स्याद् । ङीष एव त्वनुदात्तत्वविधाने ङीषोत्र प्रतिषिद्धत्वाद्दोषाभावः ॥ तदेवं नित्ये स्वरमात्रविधाने नास्ति सामान्यविशेषविहितत्वम् ॥

(उद्द्योतः) वार्तिककारस्येति । यदि त्वसंयोगोपधादित्याद्यनुवर्त्यापूर्वो ङीब्विधीयते तदा प्रयोजनं भवत्येवेत्येवमुक्तम् ॥ इत्यादावपि स्यादिति । असंयोगोपधादित्याद्यनुवृत्तौ प्रतिपत्तिगौरवमिति वार्तिकाशय इति भावः ॥ ङीष एव त्वनुदात्तत्वविधाने इति । ङीबादेशद्वारेत्यर्थः ॥ नित्ये स्वरमात्रविधाने इत्यस्यापि स्वरमात्रफलके ङीबादेशविधाने इत्यर्थः । नित्यत्वं वाग्रहणाननुवृत्तेः । तदनुवृत्तौ हि पक्षे ङीष्श्रवणं स्यादेवेति भावः ॥

(प्रयोजनान्तरभाष्यम्)

इदं तर्हि प्रयोजनम्—'अर्द्धपिप्पली, आर्द्धकोशातकी' एकदेशिसमासेन मुक्ते षष्ठीसमासो न भवति ॥ उन्मत्तगङ्गं लोहितगङ्गम् अव्ययीभावेन मुक्ते बहुव्रीहिर्न भवति ॥ दाक्षिः प्लाक्षिः, इञा मुक्तेऽण् न भवति ॥

(उद्द्योतः) भाष्ये—इदं तर्हि प्रयोजनमर्धपिप्पलीत्यादि परवल्लिङ्गमितिसूत्रस्थभाष्येणेदं विरुध्यते । तत्र हि एकदेशिसमासो नारप्स्यते । कथमर्धपिप्पलीति? । समानाधिकरणो भविष्यति । अर्धं चासौ पिप्पली चेति । [न चैकदेशिसमासारम्भे षष्ठीसमासस्य तेन बाधो भवति अन्यथा षष्ठीसमासोपि प्राप्नोति] इष्यते षष्ठीसमासोपि अपूपार्धं मया भक्षितं लब्धं मया ग्रामार्धमिति । एवं पिप्पल्यर्धमित्यपि भवितव्यमित्युक्तम् ॥ तस्माद्यथाश्रुतसूत्रमते एकदेश्युक्तिरियम् ॥ उन्मत्तगङ्गम् अव्ययीभावेनेति । यद्यपि वाक्येन संज्ञानवगमात् सोव्ययीभावो नित्यसमाससदृशः तद्वत्समासान्यूनार्थकवाक्याभावात् तथापि वापदं तत्र संबध्यत एव । अत एव वाक्यं भवत्येव । अत एव संज्ञायामिति समासविषयेपि वाप्याश्वो वाप्यश्व इति वाक्यं भाष्योक्तं संगच्छत इति भावः ॥

(आक्षेपभाष्यम्)

यद्येतज्ज्ञाप्यते, उपगोरपत्यमौपगवः तद्धितेन मुक्ते उपग्वपत्यमिति न सिध्यति ॥

(समाधानभाष्यम्)

अस्त्यत्र विशेषः—द्वे ह्यत्र विभाषे "दैवयज्ञिशौचिवृक्षिसात्यमुग्रिकाण्ठेविद्धिभ्योऽन्यतरस्याम्" "समर्थानां प्रथमाद्वा" इति च। तत्रैकया वृत्तिर्विभाषा। अपरया वृत्तिविषये विभाषापवादः ॥

(प्रदीपः) वृत्तिविषय इति । एकार्थीभावविषय इत्यर्थः ॥

(आक्षेपभाष्यम्)

क्रियमाणेपि वै अन्यतरस्यांग्रहणे षष्ठीसमासो न प्राप्नोति । किं कारणम्? । पूरणेनेति प्रतिषेधात् ॥

(समाधानभाष्यम्)

नैतत्पूरणान्तम्। अना एतत्पर्यवपन्नम् ॥

(प्रदीपः) नैतदिति । पूरणगुणेत्यत्र पूरणाधिकारविहितप्रत्ययान्तग्रहणादिति भावः ॥ अनैतदिति । पूरणाद्भागे तीयादन्निति स्वार्थिकेनाना व्यवहितमित्यर्थः ॥

(उद्योतः) पूरणाधिकारेति । पूरणशब्दस्य स्वरितत्वादित्यभिमानः ॥ पर्यवस[ि]तशब्दं व्याचष्ट—अनाव्यवहितमिति । स्वरभेदप्राप्तमिति यावत् ॥

(समाधानबाधकभाष्यम्)

एतदपि पूरणान्तमेव । कथम् ? । पूरणं नामार्थः तमाह तीयशब्दः, अतः पूरणम् । योसौ पूरणान्तात्स्वार्थे भागे अन् सोपि पूरणमेव ॥

(प्रदीपः) एतदपीति । पूरणगुणसुहितार्थेत्यत्रार्थशब्दस्य प्रत्येकं संबन्धात् पूरणार्थग्रहणं न तु तदधिकारविहितप्रत्ययग्रहणमित्यर्थः ॥ ३ ॥

(उद्योतः) ननु तदधिकारेति । एवं च सूत्रे विनिगमनाविरहाद्भाष्यप्रामाण्याच्चप्रत्ययान्तानां केवलानां च द्वितीयादीनां ग्रहणम् । भिक्षासंबन्धिद्वित्वसंख्यापूरणमित्यर्थः ॥

(समाधानान्तरभाष्यम्)

एवं तर्ह्यन्यतरस्यांग्रहणसामर्थ्यात्षष्ठीसमासो भविष्यति ॥ द्वितीयतृतीय-॥ ३ ॥

(उद्योतः) भाष्ये—एवंतर्हीति । अन्यतरस्यामित्येतत्सामर्थ्यात्पूरणेति प्रतिषेधो नेति भावः ॥ ३ ॥

(इत्येकदेशिसमासप्रकरणम्)

(२६९ तत्पुरुषसंज्ञासूत्रम् ॥ २ । २ । १ आ. ३)

४२४ प्राप्तापन्ने च द्वितीयया ॥ २।२।४॥

(चकारस्याकारविधानार्थत्वाधिकरणम्)

(आक्षेपभाष्यम्)

किमर्थश्चकारः ? ॥

(समाधानभाष्यम्)

अनुकर्षणार्थः ॥ किमनुकृष्यते ? । अन्यतरस्यामित्येतदनुकृष्यते ॥ किं प्रयोजनम् ? । अन्यतरस्यां समासो यथा स्यात् । समासेन मुक्ते वाक्यमपि यथा स्यात्—जीविकां प्राप्त इति ॥

(समाधानबाधकभाष्यम्)

नैतदस्ति प्रयोजनम् । प्रकृता महाविभाषा तया वाक्यमपि भविष्यति ॥

(समाधानान्तरभाष्यम्)

इदं तर्हि प्रयोजनम् । द्वितीयासमासोपि यथा स्यात्—जीविकाप्राप्त इति ॥

(समाधानान्तरबाधकभाष्यम्)

एतदपि नास्ति प्रयोजनम् । अयमप्युच्यते, द्वितीयासमासोपि । तदुभयं वचनाद्भविष्यति ॥

(उद्योतः) प्राप्त ॥ ४ ॥ अयमप्युच्यतइत्यादि । उभयोरपि प्राप्तापन्नग्रहणेन विशेषविहितत्वादित्यर्थः ॥

(समाधानान्तरभाष्यम्)

एवं तर्हि नायमनुकर्षणार्थश्चकारः ॥ किं तर्हि ? । अत्वमनेन विधीयते—प्राप्तापन्ने द्वितीयान्तेन समस्येते, अत्वं च भवति प्राप्तापन्नयोरिति । प्राप्ता जीविकां प्राप्तजीविका । आपन्ना जीविकामापन्नजीविका ॥ प्राप्तापन्ने ॥ ४ ॥

(प्रदीपः) प्राप्त ॥ ४ ॥ अत्वं च भवतीति । चकारेण समुच्चयार्थेनाकारप्रश्लेषोनुमीयते । सौत्रत्वाच्च निर्देशस्य प्रकृतिभावः प्रगृह्याश्रयो न भवति । यद्वा समाहारद्वन्द्वे कृते विषयसप्तम्यकारादेशापेक्षा क्रियते सुपिति चानुवर्तनात् प्राप्तापन्नयोरेव सन्निधानात् उपसर्जनसंज्ञा भवति । सूत्रारम्भसामर्थ्याद्वा ॥ प्राप्ता जीविकामिति । लिङ्गविशिष्टपरिभाषया प्राप्ताशब्दस्य समासः ॥ ४ ॥

(उद्योतः) द्वितीययेत्यत्र प्रश्लेषे उद्देश्यासंनिधानं चकारेण व्यवधानं नेति भावेनाह—सौत्रत्वाच्चेति । सूत्रारम्भेति । द्वितीयाश्रितेत्येव सिद्धे एतत्सामर्थ्यादिति भावः ॥ लिङ्गविशिष्टेति । एकादेशस्य पूर्वान्तत्वादित्यपि बोध्यम् ॥ ४ ॥

(२७० तत्पुरुषसंज्ञासूत्रम् ॥ २।२।१ आ. ४)

४२५ कालाः परिमाणिना ॥ २।२।५ ॥

(उत्तरपदार्थप्रधानताधिकरणम्)

(आक्षेपभाष्यम्)

किंप्रधानोयं समासः ? ॥

(प्रदीपः) कालाः ॥ ५ ॥ इह वृत्तिवाक्ययोः समानार्थत्वं न्याय्यं मासो जातस्येति वाक्ये जातस्य विशेषणत्वाद्प्राधान्यम्, समासे तु मासजातो द्व्यहजात इत्यादौ जातस्यैव कार्यसंबन्धावगमात् प्राधान्यमन्योत्तरपदार्थप्रधानवैधर्म्यं च लक्ष्यत इति मत्वा पृच्छति—किंप्रधान इति ॥

(उद्योतः) कालाः ॥ ५ ॥ तत्पुरुषे प्राय उत्तरपदार्थप्राधान्यात्प्रश्नानुपपत्तिमाशङ्क्याह—इहेति ॥ प्राधान्यमिति । एवं च समानार्थत्वभङ्ग इति भावः ॥ ननु चित्रगुरित्यादिवत्समासे उत्तरपदार्थप्राधान्यं एकार्थीभावकृतं स्यात्तत्राह—अन्योत्तरेति । तद्वैधर्म्यं च भाष्योक्तम् । किं च वाक्यविपरीतविशेषणविशेष्यभावो नैकार्थीभावसाध्यः अत एव तस्य एकार्थीभावकृतविशेषेषु भाष्ये गणनाभावः ॥ किंप्रधानोयं समास इति । समासपदं विग्रहपरमपि ॥

(समाधानभाष्यम्)

उत्तरपदार्थप्रधानः ॥

(उद्योतः) उत्तरपदार्थप्रधानइत्युत्तरमप्युभयसाधारणम् । न च विग्रहेपि जातस्य प्राधान्ये जातस्य मास इति षष्ठ्यनुपपत्तिः विशेषणादेव षष्ठीविधानादिति वाच्यं, वृत्तिविग्रहयोः समानार्थत्वानुरोधेन तस्य वाक्यस्य वृत्त्यर्थबोधकत्वविवक्षायां विशेष्यविशेषणभाववैपरीत्येपि पूर्वजातसंस्कारानिवृत्तेः । अन्यथा समासे जातप्राधान्येन विशेषणविभक्तिषष्ठ्यापादनस्य भाष्येसङ्गत्यापत्तेः । मम तु न दोषः विग्रहेपि तस्यैव प्राधान्येन तत्स्थितिवत्समासादपि तद्बोधादनात् । तदुत्तरषष्ठ्यैव तत्र मासविशेषणकसम्बन्धप्रतीतिवत्समासे विशिष्टेत्तरपष्ठ्या तत्सम्भव इत्याशयात् ॥ सम्बन्धस्याक्षेपत्वान्न षष्ठीत्युत्तरम् ॥

(आक्षेपभाष्यम्)

यद्युत्तरपदार्थप्रधानः सधर्मणानेनान्यैरुत्तरपदार्थप्रधानैर्भवितव्यम् । अन्येषु चोत्तरपदार्थप्रधानेषु यैवासावन्तर्वर्तिनी विभक्तिस्तस्याः समासेपि श्रवणं भवति । तद्यथा—राज्ञः पुरुषो राजपुरुष इति । इह पुनर्वाक्ये षष्ठी, समासे प्रथमा । केनैतदेवं भवति? ॥

(उद्योतः) भाष्ये—यैवासावन्तर्वर्तिनीति । उत्तरपद इति शेषः ॥

(समाधानभाष्यम्)

योसौ मासजातयोरभिसंबन्धः समासे स निवर्तते । अभिहितः सोर्थोन्तर्भूतः प्रातिपदिकार्थः संपन्नः । तत्र प्रातिपदिकार्थे प्रथमेति प्रथमा भविष्यति ॥

(प्रदीपः) योसाविति । षष्ठीनिवृत्तौ न्यायकथनं संबन्धस्य चान्तर्भावादनुद्भव एव निवृत्तिः ॥ अभिहित इति । प्रथमोत्पत्तिनिमित्तकथनम् । अनुद्भूतोपि संबन्धो गुणभावेन समासाभिधेयत्वादभिहित इत्युच्यते । तत्राभिहितोपि कश्चिदन्तर्भवति यथा राज्ञः पुरुष इत्यत्र वाक्ये षष्ठ्या संबन्धोभिधीयते न तु कश्चिदन्तर्भावमुपयाति । राजसखादौ बहुव्रीह्यर्थस्यान्तर्भावोऽस्ति न त्वभिधानमित्युभयोपादानम् । इह परिमाणं जातस्य प्रतिपादयितुं वाक्ये परिमाणिन एव षष्ठी कर्तव्या मासो जातस्येति । मासस्य जात इति ह्यभिधीयमाने विवक्षितोर्थो न प्रतीयते । तत्र यथा चित्रा गावोस्येति वाक्ये यद्यपि गवां प्राधान्यं तथापि चित्रगुरिति वृत्तावप्राधान्यमेव तथेहापि वृत्तिवाक्ययोः परिमाणिनः प्राधान्याप्राधान्ये शब्दशक्तिस्वाभाव्याद्भवतः ॥

(उद्योतः) योसाविति । परिच्छेद्यपरिच्छेदकभावः ॥ समासे इति । षष्ठ्यप्रयोजको न भवतीत्यर्थः । तदाह—अभिहित इति । षष्ठ्यप्रवृत्तौ निमित्तमिदम्, समासेनाभिहितो यतः अतएवान्तर्भूतः प्रथमोत्पत्तिनिमित्तमाह—प्रातिपदिकार्थ इति । हि यतोभिहितः, अत एव प्रातिपदिकार्थः संपन्न इत्यर्थः । अन्यथा पचतीत्यादौ कर्ताभिधीयमानो गुणभूतत्वादन्तर्भूतोपीति तत्रापि प्रथमा स्यादत इदमुक्तम् । अनभिहितसम्बन्ध एव षष्ठीति तात्पर्यम् ॥ अन्तर्भावादिति । सम्बन्धिविषयकोपस्थितिविषयत्वादित्यर्थः ॥ अनुद्भव एवेति । पृथगुपस्थित्यविषयसम्बन्धित्वमनुद्भवः ॥ प्रथमोत्पत्तिनिमित्तमिति । षष्ठीप्रतिबन्धद्वारेत्यर्थः ॥ ननु पक्व इत्यादौ तत्त्वेनाभिधीयमानं कर्मादिकमभिहितमित्युच्यते नैष तथासम्बन्धत्वेनाभानादत आह—गुणभावेनेति । सम्बन्धाभिधानमेव भवतीत्यर्थः । सम्बन्धिविषयकोपस्थितिविषयत्वमेव गुणभाव इत्याहुः ॥ ननु क्वचिदन्तर्भावमिति । न सम्बन्धिविषयकोपस्थितौ विषयो भवतीत्यर्थः । उभयोः पृथगुपस्थितयोरेव सम्बन्धसम्भवादिति भावः ॥ विवक्षितोर्थ इति । कियान्कालोस्य जातस्येति प्रश्ने जातस्य मास इत्युत्तरेणैवाकाङ्क्षाशान्तिर्न तु मासस्य जात इति उत्तरेणेति स एव विवक्षितोर्थः । स च न ततः प्रतीयत इति भावः ॥ मासजात इति । समासे त्वर्थमुत्तरत्वं बोध्यम् ॥ नन्वेवं विग्रहे षष्ठीसमासेनैव सिद्धौ सूत्रं व्यर्थम्, उक्तं तु तथैव भाष्यार्थमेवेति चेत् । न, एतद्भाष्यप्रामाण्येन परिच्छेद्यपरिच्छेदकसमभिव्याहारे परिच्छेद्यबोधकादेव षष्ठीतिर्स्वीकारात् अवयवावयविनोः समभिव्याहारे यथावयववाचकादेव । तन्नार्थे जातमास इत्यनिष्टनिवृत्त्यर्थं सूत्रम् ॥ शब्दशक्तिस्वाभाव्यादिति । यद्यपि एतद्भाष्यात्तद्बहुव्रीहिणि सूत्रभाष्याच्च वृत्त्यर्थोपदर्शके विग्रहवाक्येपि तत्समानैव विषयतेति लभ्यते तथाप्यत्र वाक्यपदमर्थबोधाय प्रयुक्तस्वतन्त्रवाक्यपरमिति बोध्यम् । भाष्येप्येवमेव ॥

(आक्षेपभाष्यम्)

न तर्हीदानीमिदं भवति—मासजातस्येति? ॥

(समाधानभाष्यम्)

भवति बाह्यमर्थमभिसमीक्ष्य षष्ठी ॥

(प्रदीपः) भवति बाह्यमिति । परिमाणपरिमाणिसंबन्ध एव समासेन्तर्भूतः, न तु बाह्यसंबन्ध्यपेक्षो मासजातस्य वस्त्रमित्यादिरपि संबन्ध इत्यर्थः ॥

(अनुपपत्तिपरिहाराधिकरणम्)

(१३७२ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ कालस्य येन समासस्तस्यापरिमाणित्वादनिर्देशः ॥ * ॥

(व्याख्याभाष्यम्)

कालस्य येन समासः सोपरिमाणी । तस्यापरिमाणित्वाद् अनिर्देशः—अगमको निर्देशः अनिर्देशः । नहि जातस्य मासः परिमाणम् । कस्य तर्हि? । त्रिंशद्रात्रस्य । तद्यथा 'द्रोणो व्रदराणां

देवदत्तस्य' इति न देवदत्तस्य द्रोणः परिमाणम् । कस्य तर्हि ? । बदराणाम् ॥

(प्रदीपः) नहि जातस्येति । तस्य हि दिष्ट्यादिः परिमाणं, न तु मासः । नापि तत्सत्ताया मासः परिमाणम्, सत्ताया नित्यत्वात् । नापि जन्मक्रियायाः, तस्या एकक्षणभावित्वान्मासेन संबन्धासंभवात् ॥ त्रिंशद्रात्रस्येति । ननु त्रिंशद्रात्र एव मासो नापर इति भेदाभावादयुक्तमेतत् । नैष दोषः । कालो जातस्य मासेन परिच्छिद्यते । तथा हि—'कियान् कालोस्य जातस्य' इति प्रश्ने 'मास' इत्यादि प्रतिवचनम् । स च परिच्छिद्यमानस्त्रिंशद्रात्रात्मक एव संपद्यत इत्यभिप्रायेणैतदुक्तम् ॥ एतदेव दृष्टान्तेन दर्शयति—तद्यथेति ॥

(उद्द्योतः) सत्ताया नित्यत्वादिति । नित्यत्वमत्र परिच्छेदककालाधिककालस्थायित्वं बोध्यम् ॥ इत्यभिप्रायेणेति । जातसम्बन्धी कालो मास इत्यभिप्रायः ॥ भाष्ये—बदराणामिति । देवदत्तसम्बन्धिबदराणामित्यर्थः ॥

(१३४३ समाधानवार्तिकम् ॥ २ ॥)

॥ * ॥ सिद्धं तु कालपरिमाणं यस्य स कालस्तेन ॥ * ॥

(व्याख्याभाष्यम्)

सिद्धमेतत् । कथम् ? । कालपरिमाणं यस्य स कालस्तेन समस्यत इति वक्तव्यम् ॥

(प्रदीपः) सिद्धं त्विति । कालशब्देन कालसामान्यमुच्यते यस्य जातादेः संबन्धिनः कालसामान्यस्य परिमाणं मासादिस्तेन स कालो मासादिः समस्यते । अथ वा कालशब्देन मासादिः कालविशेष उच्यते स कालः परिमाणं यस्य कालसामान्यस्य तद्यस्य संबन्धि तेन स कालो मासादिः समस्यत इत्यर्थः ॥

(उद्द्योतः) कालशब्देनेति ॥ कालपरिमाणमिति षष्ठीतत्पुरुषः ॥ अत्र व्याख्याने वार्तिकस्थकालपदार्थयोः स्वरसत ऐक्यं प्रतीयमानं भज्येतेत्यत आह—अथवेति । अत्र पक्षे कालपरिमाणमिति बहुव्रीहिः ॥ तद्यस्येति । तत्कालसामान्यं जातमपि प्रतीतिजननक्रियापरिच्छेदद्वारेत्यर्थः ॥

(आक्षेपभाष्यम्)

सिध्यति । सूत्रं तर्हि भिद्यते ? ॥

(समाधानभाष्यम्)

यथान्यासमेवास्तु ॥

(आक्षेपस्मारणभाष्यम्)

ननु चोक्तम्—*कालस्य येन समासस्तस्यापरिमाणित्वादनिर्देशः* इति ॥

(प्रत्याक्षेपभाष्यम्)

कं पुनर्भवान्कालं मत्वाह—*कालस्य येन समासस्तस्यापरिमाणित्वादनिर्देशः* इति? ॥

(प्रदीपः) कं पुनरिति । यदि नित्य एको विभुः कालस्तदा तस्य भेदाभावात् परिच्छेदकत्वासंभवः । अथोपाधिभेदात्तस्य भेदस्तदा तद्भेदभिन्नस्य जातं प्रत्यपि परिच्छेदकत्वमस्त्येव ॥

(प्रत्याक्षेपसमाधानभाष्यम्)

येन मूर्तीनामुपचयाश्चापचयाश्च लक्ष्यन्ते तं कालमित्याहुः । तस्यैव कयाचित्क्रियया युक्तस्याहरिति च भवति रात्रिरिति च ॥ कया क्रियया ? । आदित्यगत्या । तयैवासकृदावृत्तया मास इति भवति । संवत्सर इति च भवति ॥

(प्रदीपः) येन मूर्तीनामिति । तरुतृणलताप्रभृतीनां कदाचिदुपचयः, अन्यदा त्वपचयः । स प्रत्ययान्तराविशेषेपि यत्कृतः स काल इत्यर्थः ॥ यद्येवं तस्यैकत्वात् कथमहरादिविभाग इत्याह—तस्यैवेति । परोपाधिक एव सर्वस्य भेदः । तथा चोक्तं हरिणा कालसमुद्देशे—

तस्यात्मा बहुधा भिन्नो भेदैर्धर्मान्तराश्रयैः ।
न हि भिन्नमभिन्नं वा वस्तु किञ्चन विद्यते ॥१॥
नैको न चाप्यनेकोस्ति न शुक्लो नापि चासितः ।
द्रव्यात्मा स तु संसर्गादेवंरूपः प्रकाशते ॥२॥
संसर्गिणां तु ये भेदा विशेषास्तस्य ते मताः ।
संभिन्नस्तैर्व्यवस्थानां कालो भेदाय कल्पते ॥३॥

इति ॥ कया क्रिययेति । क्रियाया एकत्वात्तस्या अपि भेदकत्वं नास्तीति प्रश्नः ॥ आदित्यगत्येति । आदित्यादिसाधनभेदाद्भिन्नैव क्रिया । आख्यातेन तु सा निवृत्तभेदोच्यते शब्दशक्तिस्वाभाव्यात्र तु तस्या भेदो नास्ति ॥

(उद्द्योतः) तरुतृणेति । पदार्थानामनन्यथासिद्धवृद्ध्यपेक्षयानुमेयः काल इति भाष्याशय इति भावः ॥ प्रत्ययान्तरम् । कारणान्तरम् ॥ तस्यैकत्वादिति । अखण्डकालाभिप्रायमिदम् ॥ वस्तुतस्तु एकत्वे तस्य कार्यवैचित्र्यनियामकत्वानुपपत्तिरिति भाष्योक्तलक्षणानुपपत्त्या क्षणधारारूपः काल इति युक्तम् । क्षणानां चाशुविनाशित्वात् कथमहरादिविभाग इति चावतरणं युक्तं कैयटेपि ॥ नित्यः प्रवाहनित्यतया, एकः समूहरूपेण, विभुः क्षणस्य विभु-

त्वात्, तस्य समूहस्यैकत्वात् इत्यर्थ इत्यन्ये ॥ **इत्याहेति** । इति हेतोराहेत्यर्थः ॥ भाष्ये—**तस्यैवेति** । बुद्धिविषयक्षणसमूहस्येत्यर्थः ॥ **क्रिययेति** । क्रियासमूहेनेत्यर्थः ॥ नन्वौपाधिकत्वेऽपरमार्थता स्यादत आह—**परोपाधिक एवेति** । व्यवहारमात्रस्यौपाधिकत्वाद्यावद्बाधं प्रामाण्यमङ्गीकार्यमिति भावः ॥ तत्रार्थे वृद्धसम्मतिमाह—**तथाचेति** ॥ **तस्य** । क्षणसमूहरूपकालस्य ॥ **आत्मा**, स्वरूपं, **धर्म्यन्तराश्रयैः** धर्मी सूर्यस्तद्वृत्ति अन्तरं धर्मान्तरं धर्मविशेषः क्रियारूपः स आश्रयो येषां तैः क्रियाश्रितैः । **भेदैः** विशेषैः । **बहुधा** अहरादिभेदेन ॥ न केवलं कालस्यैव भेद औपाधिकः किं तु सर्वस्यापीत्याह—**नहीति** । भेदाभेदौ एकत्वानेकत्वे, शुक्लत्वकृष्णत्वे इत्यादिसर्वमपि न कस्यचित्स्वाभाविकमित्यर्थः ॥ तदुक्तं **नहि गौः स्वरूपेण गौः नाप्यगौः गोत्वाभिसम्बन्धात्तु गौरिति**॥ किं त्वौपाधिकमेवेत्याह—**द्रव्यात्मेति** । द्रव्यपदार्थस्तत्तत्संसर्गादेकत्वानेकत्वादिनानाव्यवहारविषय इत्यर्थः । एवं च मयैव कल्पिततत्तत्पदार्थसंसर्गात् भेदाभेदैकत्वानैकत्वशुक्लत्वकृष्णत्वादिना भासते इति भावः ॥ वस्तुतस्तु सर्वधर्मविनिर्मुक्तमिति बोध्यम् ॥ प्रकृते आह—**संसर्गिणां त्विति** । आदित्यक्रियादीनां ये भेदा विशेषास्त एव तस्य कालस्य विशेषा अहरादिविशेषव्यवहारहेतव इत्यर्थः । तैर्भिन्नरूपः कालो अवस्थानां अहरादिव्यवहाराणां भेदाय विशेषाय कल्पत इत्यर्थः ॥ **क्रियाया एकत्वादिति** । गच्छतीत्यादितस्तथाप्रतीतेरिति भावः ॥ **आख्यातेन त्विति** । स्वतो निवृत्तभेदैवेत्यर्थः ॥ अन्ये तु दिनपर्यन्तस्थायिक्रियानुपलम्भात् प्रश्नः—**कयेति** । **आदित्यगत्येति** उत्तरम् । तत्क्रियासमूहस्य तावत्कालं धारारूपेणानुस्यूतत्वादित्यर्थ इत्याहुः ॥

(प्रत्याक्षेपसमाधानेन समाधानभाष्यम्)

यद्येवम्, भवति—जातस्य मासः परिमाणम् ॥

(प्रदीपः) **यद्येवमिति** । जातस्य जननक्रियावधिर्मासेन परिच्छिद्यते । न च मासव्यतिरिक्तः कश्चित् त्रिंशद्रात्रोऽस्ति यस्य मासः परिमाणं स्यात् । न च कालसामान्यं परिच्छेद्यम्, काल एव हि संसर्गिभेदावाप्तमासादिभेदव्यवहारः क्रियायाः परिमाणं न वस्त्वन्तरस्य ॥

(उद्योतः) ननु क्रियापरिच्छेदकत्वमेव कालस्य, न तु द्रव्यपरिच्छेदकत्वम्, द्रव्यस्य हि वितस्त्याद्येव परिच्छेदकमत आह—**जातस्य जननक्रियावधिरिति** । मासो जातस्येत्यस्य जननक्रियाया ऊर्ध्वमस्य मासो जात इत्यर्थ इत्यभिप्रायः । एवं च जननक्रियापरिच्छेदद्वारा जातपरिच्छेदकत्वमिति तात्पर्यम् ॥ मासस्य परिच्छेद्यान्तरमुक्तं निराकरोति—**न च मासेति** । **त्रिंशद्रात्र इति** बहुव्रीहिः । पद्मनाभवत्पृषोदरादित्वेनाकारान्तता, समूहोऽन्यपदार्थः । समाहारद्विगौ **संख्यापूर्वं रात्रं क्लीबमिति** नपुंसकतापत्तेः ॥ **न च कालसामान्यमिति** । तस्य नित्यत्वाद्विभुत्वाच्चेति भावः । क्षणपक्षे तद्द्वाराऽविच्छेदेन तस्यानन्तत्वादपरिच्छेद्यत्वमिति भावः ॥ युक्त्यन्तरमप्याह—**न वस्त्वन्तरस्येति** । एवं च क्रियाद्वारैव कालपरिच्छेदकत्वं वाच्यमिति तद्द्वारा जातपरिच्छेदकत्वमेवेति भावः ॥

(१३४४ आक्षेपवार्तिकम् ॥ ३ ॥)

॥ * ॥ एकवचनद्विगोश्चोपसंख्यानम् ॥ * ॥

(व्याख्याभाष्यम्)

एकवचनान्तानामिति वक्तव्यम् । इह मा भूत् मासौ जातस्य मासा जातस्येति ॥ द्विगोश्चेति वक्तव्यम् । इहापि यथा स्यात्—द्विमासजातस्त्रिमासजातः ॥

(समाधानभाष्यम्)

उक्तं वा ॥ किमुक्तम् ? । एकवचने तावदुक्तम्—अनभिधानादिति ॥ द्विगोः किमुक्तम् ? ॥ *उत्तरपदेन परिमाणिना द्विगोः समासवचनम्* इति ॥ कालाः परि ॥ ५ ॥

(प्रदीपः) **अनभिधानादिति** । समासे द्वित्वादेरनवगमात् । एकत्वं त्वत्र प्रातिपदिकार्थस्य तथाभूतत्वात् प्रतीयते वस्त्वन्तरानपेक्षत्वाच्च । द्वितादिका तु संख्या वस्त्वन्तरापेक्षत्वाद् बहिरङ्गा ॥ तदुक्तं हरिणा—

शौर्पिके मासजाते च परिमाणं स्वभावतः ।
उपाधिभूतमाश्रित्य संख्या भेदेन वर्तते" इति ॥

उत्तरपदेनेति । तद्धितार्थेत्यत्रेदमुक्तं तदेव शिष्यानुग्रहाय स्मारितम् ॥ ५ ॥

(उद्योतः) ननु संख्याविशेषैकत्वावगतिरपि न स्यात आह—**एकत्वं त्विति** ॥ **तथाभूतत्वात्** । नियतपरिच्छेदकपरिमाणवाचित्वात् । अन्यथा 'जातस्यास्य कियान्काल' इतिप्रश्नेऽस्योत्तरत्वं न स्यादित्यर्थः ॥ नन्वेवं सति तात्पर्ये द्वित्वाद्यवगतिरपि स्यादत आह—**बहिरङ्गेति** । द्वित्वादिप्रतीतेरनुभवविरुद्धत्वाच्चेत्यपि बोध्यम् ॥ **शौर्पिक इति** । **परिमाण**मक्तपरिमाणत्वं उपाधिमाश्रित्य **संख्या**, एकत्वरूपा, **भेदेन**, तद्रूपेण, भासते इत्यर्थः ॥ अक्तपरिमाणवाचकशब्दस्थले तथैव व्युत्पत्तिरिति तात्पर्यम् । वस्तुतः समासे एकत्वमपि नैव भासते । किं तु मासत्वेनैकमासस्यैव भानं न त्वनेकस्यानभिधानादिति भाष्याशयः ॥ एवं शौर्पिकतावर्कानादावपीत्थं बोध्यम् ॥ इदमनभिधानं **समर्थ**सूत्रे उक्तम् एकार्थीभावकृतविशेषनिरूपणावसरे ॥ तुल्यन्यायादक्षशलाकेतिसूत्रस्थम् "एकवचनान्तयोः" इत्यपि प्रत्याख्यातं बोध्यम् ॥ ५ ॥

(२७१ तत्पुरुषसंज्ञासूत्रम् ॥ २ । २ । १ आ. ५)

४२६ नञ् ॥ २।२।६ ॥

(नञ्समासस्याप्युत्तरपदार्थप्रधानतासाधनाधिकरणम्)

(आक्षेपभाष्यम्)

किंप्रधानोयं समासः ? ॥

(प्रदीपः) नञ् ॥ ६ ॥ इहाब्राह्मणादिना क्षत्रियादेरभिधानं लोके दृश्यते तत्र प्रक्रियागतगुणदोषनिरूपणाय प्रश्नः—**किंप्रधान इति** ॥

(उद्द्योतः) नञ् ॥ ६ ॥ शब्दार्थावगतेर्वृद्धव्यवहाराधीनत्वेपि न्यायव्युत्पादनाय विचार इत्याह—**इहेति** ॥ **प्रक्रियागतेति** । लिङ्गसंख्यादिसिद्धितदभावरूपगुणदोषेत्यर्थः ॥

(समाधानभाष्यम्)

उत्तरपदार्थप्रधानः ॥

(प्रदीपः) त्रयश्चात्र पक्षा अन्यपदपूर्वपदोत्तरपदार्थप्राधान्यलक्षणाः संभवन्ति । यदा जातौ ब्राह्मणशब्दो वर्तते अविद्यमानं ब्राह्मण्यं यस्य सोऽब्राह्मणः क्षत्रियादिस्तदान्यपदार्थः प्रधानम् । यदा त्वसत्सामान्यवृत्तिर्नञ् ब्राह्मणादिभिर्विशेष्यते ब्राह्मणत्वेनासन् अन्यथा तु सन्नर्थः क्षत्रियादिरब्राह्मणशब्देनोच्यते तदा पूर्वपदार्थः प्रधानम् । यदा तु दुरुपदेशान्मिथ्याज्ञानाद्वा ब्राह्मणशब्दः क्षत्रिये प्रयुज्यते ब्राह्मणपदार्थनिवृत्तिश्च स्वाभाविकी नञा द्योत्यते तदोत्तरपदार्थप्रधानः । यद्यपि इहार्थो न निर्दिष्टस्तथाप्यभिधानशक्तिस्वाभाव्याल्लभ्यते । द्वन्द्ववत्तु स्वतन्त्रपदार्थद्वयानवगमादुभयपदार्थप्राधान्यं नाशङ्कितम् । एवं पक्षत्रयसंभवेऽल्पप्रतिविधेयपक्षमाश्रयितुमाह—**उत्तरपदार्थप्रधान इति** ॥

(उद्द्योतः) **असत्सामान्यम्** अभावो भेदः । तस्यासत्त्वं निरूपयितुमशक्यत्वात् । तथाहि—भिन्नाभ्यां हि धर्मिप्रतियोगिभ्यां स निरूप्यः । तत्रायमेव स चेत् आत्माश्रयः अन्यश्चेदन्योन्याश्रयः । तृतीयादेरन्यस्य स्वीकारे चक्रकमनवस्था चेति । तथान्तरे स्फुटं सामान्यत्वं च केवलान्वयित्वात् ॥ तद्वृत्तिः । तद्वृत्तिः । एवं च ब्राह्मणभिन्न इत्यर्थः फलितः ॥ **दुरुपदेशोऽमुष्मिन्नवकाशे ब्राह्मण**मित्यादिः ॥ **मिथ्याज्ञानम्** । प्रकारान्तरेण भ्रमः । ब्राह्मणपदार्थो ब्राह्मण्यम्, तस्य स्वाभाविकी निवृत्तिर्मुख्यब्राह्मण्याभावो द्योत्यते इति वक्रोक्त्या आरोपिततद्वत्ताद्योतको नञ् इत्युक्तं भवति ॥ **यद्यपीहेति** । इह सूत्रेऽस्मिन्नर्थे तत्पुरुषसंज्ञेति न निर्दिष्टमित्यर्थः ॥

(आक्षेपभाष्यम्)

यद्युत्तरपदार्थप्रधानः, अब्राह्मणमानयेत्युक्ते ब्राह्मणमात्रस्यानयनं प्राप्नोति ॥

(प्रदीपः) **ब्राह्मणमात्रस्येति** । इहानियतगुणस्य गुणविशेषप्रतिपादनाय विशेषणं प्रवर्तते न तदुपघाताय । यदि च नञा ब्राह्मणार्थः प्रतिषिध्यते तदा सर्वात्मना तदर्थस्याभावात् कथं प्राधान्यं स्यात् । तस्मात् तद्गतविशेषावचनान्ननर्थक एवेति ब्राह्मणाब्राह्मणशब्दयोः पर्यायता प्रसज्येत । अन्वाख्यानाद्धि साधुत्वमेवंभूतस्यार्थवदनर्थकावयवस्य समासस्य स्यात् ॥

(उद्द्योतः) **यदि च नञेति** । यदि नञा ब्राह्मणार्थः प्रतिषिध्यते स्वार्थप्रतिषेधे रूपाभावविशिष्टो बोध्यते तदाऽभावप्रतियोगी ब्राह्मण इत्यर्थे सर्वात्मना ब्राह्मणेतरव्यावृत्तस्य नञर्थस्याभावात् किंनिरूपितं परिच्छेद्यत्वरूपप्राधान्यं स्यात् । अभावप्रतियोगित्वादेः केवलान्वयित्वात् । तदेवाह—**तद्गतविशेषावचनान्ननर्थक एवे**त्यादि ॥ नन्वनर्थकत्वे साधुत्वं न स्यादत आह—**अन्वाख्यानाद्धीति** ॥

(समाधानभाष्यम्)

अन्यपदार्थप्रधानस्तर्हि भविष्यति ॥

(आक्षेपभाष्यम्)

यदि अन्यपदार्थप्रधानः 'अवर्षा हेमन्तः' इति हेमन्तस्य यल्लिङ्गं वचनं च तत्समासस्यापि प्राप्नोति ॥

(प्रदीपः) **अवर्षा इति** । न चात्र परवल्लिङ्गतास्ति । यस्माभ्यासभेदेन द्वन्द्वैकदेशिसमासयोरेव सोक्ता । वचनदोषस्तु यथान्यासेप्यपरिहार्य एव । किञ्च नञ्समासस्यान्यपदार्थप्रधानत्व आश्रीयमाणेऽपवादत्वादनेन बहुव्रीहेर्बाधनादब्राह्मणको देश इत्यादि न सिध्यति । अतः असर्वस्मायिति चोत्तरपदार्थस्योपसर्जनत्वात्स्यदादिसर्वनामकार्याप्रसङ्गः **सर्वादीनि सर्वनामानी**त्यत्र संज्ञोपसर्जनस्य प्रतिषेधाभिधानात् ॥

(उद्द्योतः) **द्वन्द्वैकदेशिसमासयोरिति** । उपमितसमासः समानलिङ्गयोरेवेति भावः ॥ **अब्राह्मणको देश इत्यादि न सिध्यतीति** । नहि प्रवृत्तिनिमित्तमात्रनिष्ठेषु ब्राह्मणादिशब्देष्वेवायं समासो, न तद्वन्निष्ठेष्वित्यत्र नियामकमस्तीति भावः ॥ **नञोस्त्यर्थाना**मिति तत्सूत्रस्थवार्तिकाद्विषयविभागो लभ्यते । **एतत्तदोरि**ति सूत्रेऽनञ्समासग्रहणाल्लिङ्गाच्चमिति सूत्रविहितसमासे उपसर्जनत्वप्रयुक्तकार्याभाव इति भाष्याशय इत्यन्ये ॥

(समाधानभाष्यम्)

पूर्वपदार्थप्रधानस्तर्हि भविष्यति ॥

(आक्षेपभाष्यम्)

यदि पूर्वपदार्थप्रधानः, अव्ययसंज्ञा प्राप्नोति । अव्ययं ह्यस्य पूर्वपदमिति ॥

(प्रदीपः) **अव्ययसंज्ञेति** । **अलिङ्गमसंख्यमव्यय**मित्यर्थाश्रयेणाव्ययसंज्ञाविधानादिति भावः ॥

(आक्षेपबाधकभाष्यम्)

नैष दोषः । पाठेनाव्ययसंज्ञा क्रियते । न च नञ्समासस्तत्र पठ्यते ॥

(प्रदीपः) पक्षान्तराश्रयेणापि परिहारा भवन्तीति पाठमाश्रित्याह—**नैष दोष इति** ॥

(आक्षेपसाधकभाष्यम्)

यद्यपि नञ्समासो न तत्र पठ्यते, नञ् तु पठ्यते ॥ पाठेनाप्यव्ययसंज्ञायां सत्यामभिधेयवल्लिङ्गवचनानि भवन्ति । यश्चेहार्थोऽभिधीयते न तस्य लिङ्गसंख्याभ्यां योगोऽस्ति ॥

(प्रदीपः) **पाठेनापीति** । पाठाभावात्समासस्य मा भूदव्ययसंज्ञा, लिङ्गसंख्यायोगस्तु नञर्थप्रधानत्वान्न प्राप्नोतीत्यर्थः ॥

(उद्द्योतः) ननु नञः पाठेऽपि तदन्तत्वाभावादव्ययत्वाप्राप्तिरत्राह—भाष्ये—**पाठेनापीति** । एवं च नञः पाठेनाव्ययतदा तदर्थस्य लिङ्गसंख्यानन्वयित्वेन समासेऽपि तदर्थस्य प्राधान्ये स न स्यादिति भावः ॥

(समाधानभाष्यम्)

नेदं वाचनिकमलिङ्गता असंख्यता वा ॥ किं तर्हि? । स्वाभाविकमेतत् । तद्यथा—समानमीहमानानां चाधीयानानां च केचिदर्थैर्युज्यन्ते । अपरे न । न चेदानीं कश्चिदर्थवानिति कृत्वा सर्वैरर्थवद्भिः शक्यं भवितुम्, कश्चिद्वानर्थक इति सर्वैरनर्थकैः । तत्र किमस्माभिः शक्यं कर्तुम्—यन्नञः प्राक् समासाल्लिङ्गसंख्याभ्यां योगो नास्ति, समासे च भवति । स्वाभाविकमेतत् ॥

(प्रदीपः) **नेदं वाचनिकमिति** । वचनं प्रयोजनमस्येति वाचनिकम् । एतदुक्तं भवति—शब्दशक्तिस्वाभाव्यादसत्त्वरूपमर्थं वाक्ये नञाह, समासे तु सत्त्वरूपम् ॥ **केचिदर्थैरिति** । धर्माधर्मवशात् ॥

(उद्द्योतः) भाष्ये—**नेदंवाचनिकं** । नेदं वचनप्रयोज्यमित्यर्थः ॥ कैयटेऽपि प्रयोजनमिति करणे ल्युट् ॥

(समाधानान्तरभाष्यम्)

अथ वा आश्रयतो लिङ्गवचनानि भविष्यन्ति । गुणवचनानां हि शब्दानामाश्रयतो लिङ्गवचनानि भवन्ति । तद्यथा—शुक्लं वस्त्रम्, शुक्ला शाटी, शुक्लः कम्बलः, शुक्लौ कम्बलौ, शुक्लाः कम्बला इति यदसौ द्रव्यं श्रितो भवति गुणस्तस्य यल्लिङ्गं वचनं च तद्गुणस्यापि भवति । एवमिहापि यदसौ द्रव्यं श्रितो भवति समासस्तस्य यल्लिङ्गं वचनं च तत्समासस्यापि भविष्यति ॥

(प्रदीपः) **अथ वेति** । ब्राह्मणाभावस्य गुणत्वात् तदुक्तद्रव्याभिधायित्वाच्च समासस्य क्षत्रियाद्याश्रयगते लिङ्गसंख्ये भविष्यत इत्यर्थः ॥ पूर्वत्र स्वाभाविकदर्शने साक्षादेव लिङ्गसंख्यायोगः । इह त्वाश्रयद्वारक इति विशेषः ॥ **समास इति** । समासार्थ इत्यर्थः । अत्रापि पक्षे दोषः—यदि तावत् स्वाभाविकदर्शनमाश्रीयते तदानेनापवादत्वादव्ययीभावस्य बाधनप्रसङ्गादमक्षिकमित्यादि न सिध्यति । तस्य तु निर्मक्षिकमित्यादिरवकाशः । असर्वस्मायम इत्यादौ च पूर्ववत् स्मायाद्यसिद्धिः स्यात् ॥

(उद्द्योतः) **ब्राह्मणाभावस्येति** । ब्राह्मणभेदस्येत्यर्थः ॥ **गुणत्वादिति** । आश्रितत्वमत्र गुणत्वम् ॥ **तदुक्तेति** । तदुक्तद्रव्येऽभेदेनान्वयित्वादित्यर्थस्तद्वक्ष्यति—**यदसौ द्रव्यं श्रित** इति भाष्ये ॥ अयं भावः—भेद एव नञर्थः, तस्य चाश्रयेण गुणस्येव तादात्म्यं सम्बन्धः । अब्राह्मणः क्षत्रियः, ब्राह्मणभेदः क्षत्रिये इत्युभयविधव्यवहारदर्शनात् । **गुणवचनानां** गुणोपसर्जनद्रव्यवाचिनाम् **आश्रयत** आश्रयविशेषतो लिङ्गवचनानीत्यर्थः । जात्याश्रयबोधकानां तु नियतलिङ्गतैवेति भावः ॥ इह **त्वाश्रयेति** । साक्षाल्लिङ्गसंख्यानाश्रयत्वमेवासत्त्वमिति भावः ॥ भाष्ये—**यदसौ द्रव्यं श्रित इति** । यद्द्रव्यान्वयीत्यर्थः ॥ उत्तरपदार्थप्राधान्यपरिग्रहस्तुल्यविकल्पाभिप्रायेण न भवतीत्याह—**अत्रापीति** ॥ **अव्ययीभावस्येति** ॥ परे तु नञा स नेष्ट एव । असंहितमित्यत्रारोपितं संधानम् परः संनिकर्षः तदभावाद्द्रुतायां वृत्तौ संहितासंज्ञाप्रयुक्तं कार्यं न प्राप्नोतीत्यर्थ इति न दोषः । अत्यन्ताभावार्थकनञः क्रियागुणमात्रान्वयित्वेनामक्षिकमित्यादावसंहितमित्यादावुत्तरपदार्थाभावाप्रतीत्याऽव्ययीभावाप्रसक्तेश्च । अनञ्समासग्रहणात् स्मायादिसिद्धिरप्युक्तेति तुल्यविकल्पाभिप्रायेणैव भाष्यम् ॥ अवर्षा हेमन्त इत्यपि प्रतियोगिरूपाश्रयगतलिङ्गादिग्रहणाऽसिद्धम् । अभावेन प्रतियोगिनोऽपि स्वज्ञानायाश्रयणेन तस्याप्याश्रयत्वात् स्वघटितसमासघटकत्वेनोपस्थितत्वाच्चास्यैवाश्रयस्य ग्रहणम्, अन्यथा तद्दोषदूषितपक्षोऽर्धमाऽप्रितेऽपि तद्दोषानुवृत्तौ भाष्यस्य निर्दलतापत्तिः ॥ **अथ वा पुनरस्तूत्तरपदार्थप्रधान** इति समकक्षतया पक्षान्तरकथनस्यासंमतिश्चेति वदन्ति ॥ अनेकमित्यादौ वचनदोषं तु भाष्यकृदेवाग्रे वक्ष्यति ॥

(प्रागुक्तपक्षाश्रयणभाष्यम्)

अथ वा पुनरस्तु—उत्तरपदार्थप्रधानः ॥

(प्रदीपः) आश्रयद्वारकलिङ्गसंख्याभ्युपगमेऽप्यवर्षा हेमन्तोऽनर्थः स्त्रीत्यादौ हेमन्ताद्याश्रयगतलिङ्गसंख्याप्रसङ्ग इत्यालोच्याह—**अथ वेति** । **एतत्तदोः सुलोप** इत्यत्रानञ्समासग्रहणं लिङ्गमुत्तरपदार्थप्रधानत्वस्य । अन्यथैतत्तदोरर्थद्वारेण संबन्धिनः सुशब्दस्य लोपो विधीयमानोऽनेषो ददात्यसो ददातीत्यत्र कथं प्राप्नुयात् ॥

(आक्षेपस्मारणम्)

ननु चोक्तम्—अब्राह्मणमानयेत्युक्ते ब्राह्मणमात्रस्यानयनं प्राप्नोति—इति ॥

(उद्द्योतः) भाष्ये—**ब्राह्मणमात्रस्येति** । अभावो नञर्थः स विशेषणं चेत् अभावप्रतियोगी भेदप्रतियोगी वा ब्राह्मण इति बोधस्तथासति यत्किञ्चिन्निष्ठाभावप्रतियोगिनस्तादृशभेदप्रतियोगिनो वा

ब्राह्मणस्यैवानयनं प्राप्नोतीत्यर्थः । मात्रशब्देन न शौचाचारादिहीनब्राह्मणस्य नापि क्षत्रियादेरित्यर्थबोधनम् ॥

(समाधानभाष्यम्)

नैष दोषः । इदं तावदयं प्रष्टव्यः—अथेह राजपुरुषमानयेत्युक्ते पुरुषमात्रस्यानयनं कस्मान्न भवति ? ॥ अस्त्यत्र विशेषः—राजा विशेषकः प्रयुज्यते, तेन एवंविशिष्टस्यानयनं भवति ॥ इहापि तर्हि नञ्विशेषकः प्रयुज्यते, तेन नञ्विशिष्टस्यानयनं भविष्यति ॥

(प्रदीपः) **नञ्विशिष्टस्येति** । आरोपितब्राह्मण्यस्य क्षत्रियादेरित्यर्थः ॥

(उद्द्योतः) **राजाविशेषक इति** । यद्यपि पुरुषमात्रस्यैवानयनं दृश्यते न राजविशिष्टस्य तथापि राजसंबन्धिन एवानयनं न यत्किंचित्संबन्धिन इति राजा पुरुषस्य विशेषक इति भावः ॥ **नञ्विशिष्टस्येति** । नञ्द्योत्यारोपितब्राह्मण्यविशिष्टस्येत्यर्थः ॥

(आक्षेपभाष्यम्)

कः पुनरसौ ? ॥

(प्रदीपः) **कः पुनरसाविति** । भावाभावयोर्विरोधाद् नञ्विशिष्टो ब्राह्मणार्थो नोपपद्यत इति भावः ॥

(उद्द्योतः) **कः पुनरिति** । अभावस्यैव नञर्थत्वेन प्रसिद्धत्वात्प्रमितोत्तरपदार्थव्यतिरिक्तः कोसौ नञ्विशिष्ट उत्तरपदार्थ इत्याशयः ॥ ननु नञर्थस्य विशेषणत्वे किं भेदप्रतियोगी ब्राह्मण इत्यर्थः, उत भेदानुयोगी ब्राह्मण इति । भेदे प्रतियोगी चोपस्थितब्राह्मण एवेति ॥ नाद्यः ॥ ब्राह्मणमात्रस्यानयनापत्तेः । नान्त्य इत्याह—**भावाभावयोरिति** । ब्राह्मणत्वब्राह्मणप्रतियोगिकभेदयोरित्यर्थः ॥

(समाधानभाष्यम्)

निवृत्तपदार्थकः ॥

(प्रदीपः) **निवृत्तपदार्थक इति** । निवृत्तः पदार्थो मुख्यं ब्राह्मण्यं यस्मिन् स क्षत्रियादिरर्थः । सादृश्यादिनाध्यारोपितब्राह्मण्यो नञ्द्योतिततदवस्थ इत्यर्थः ॥

(उद्द्योतः) कप्प्रत्ययप्रयोगसूचितबहुव्रीहिसूचितमर्थमाह—**निवृत्त इति** ॥ सर्वथा निवृत्तपदार्थत्वे विशेषणमेव न युज्येतेत्यत आह—**सादृश्यादिनेति** । आदिना साहचर्यादिनिवृत्तमुख्यब्राह्मण्याविरारोपितसद्भाव् इति भाष्याक्षरार्थः । तदाह—**नञ्द्योतिततदवस्थ इति** ॥ एवधारोपितस्वप्रवृत्तिनिमित्तवानुत्तरपदार्थं इत्यत्र तात्पर्यग्राहको नञिति तात्पर्यम् । उत्तरपदार्थस्य प्राधान्यमप्येतदेवेति बोध्यम् ॥

(नञो वाचकत्वद्योतकत्वान्यतरनिर्णयाधिकरणम्)

(आक्षेपस्मारणम्)

यदा पुनरस्यार्थो निवर्तते । किं स्वाभाविकी निवृत्तिः, आहोस्विद्वाचनिकी ? ॥

(प्रदीपः) इदानीं नञो वाचकत्वद्योतकत्वपरीक्षणायाह—**यदा पुनरिति** । किं स्वयं निवृत्तस्य ब्राह्मणपदार्थस्य नञा निवृत्तिर्द्योत्यते । अथ स्थितस्यैव नञा निवृत्तिः क्रियते मन्त्रेणेव विषादिसामर्थ्यस्येति प्रश्नः ॥

(उद्द्योतः) **यदा पुनरिति** । याऽस्योत्तरपदस्य मुख्यार्थप्रत्ययत्यागपूर्वकमारोपितप्रवृत्तिनिमित्तकार्थबोधकता सा स्वभावसिद्धा, उत नञ्वचनेन शक्त्यारोपितत्वस्य वाचकः सन्मुख्यपदार्थप्रत्ययं निवर्तयतीति प्रश्नस्तद् ध्वनयन्नाह—**इदानीमिति** ॥ **किं स्वयमिति** । निवृत्तस्य मुख्यब्राह्मणपदार्थस्य ब्राह्मणत्वस्य निवृत्तिस्तत्पूर्वकमारोपिततद्बोधकत्वं द्योत्यते । अथ स्थितस्यैव मुख्यब्राह्मण्यस्य बोधनिवृत्तिस्तत्पूर्वकं तद्वत्त्वारोपितत्वं नञा शक्त्योच्यत इत्यर्थः ॥ ननु नञ आरोपितत्वे शक्तावपि ब्राह्मणादिपदैर्बोध्यस्य मुख्यब्राह्मण्यादेः कथमबोधोत आह—**मन्त्रेणेवेति** । नञ्सामर्थ्यादेव तन्निवृत्तिरित्यर्थः ॥

(प्रत्याक्षेपभाष्यम्)

किं चातः ? ।

(स्वाभाविकपक्षे दूषणभाष्यम्)

यदि स्वाभाविकी, किं नञ् प्रयुज्यमानः करोति ? ॥

(प्रदीपः) **किं नञिति** । ब्राह्मणशब्द एवाराच्छब्द इव दूरमदूरं च विद्यमानब्राह्मण्यमविद्यमानब्राह्मण्यं च क्षत्रियादिकं वक्ष्यतीति नास्ति नञो व्यापार इत्यर्थः ॥

(उद्द्योतः) **नास्ति नञ इति** । प्रकरणादिकं च तात्पर्यग्राहकं भविष्यतीति भावः ॥

(वाचनिकपक्षे दूषणभाष्यम्)

अथ वाचनिकी । तद्वक्तव्यम्—नञ् प्रयुज्यमानः पदार्थं निवर्तयति—इति ॥

(प्रदीपः) **अथेति** । नञः पदार्थनिवृत्तौ सामर्थ्यस्याप्रसिद्धत्वादपूर्वमेतद्वक्तव्यमिति सोत्प्रासमुपहसति ॥ **नञ्प्रयुज्यमान इति** । ननु स्वाभाविकनिवृत्तिदर्शने कथं पदार्थं नञ् निवर्तयेद् वाचनिकनिवृत्तिदर्शने स्वेतद्युज्यते वक्तुम् । एवं तर्हि पदार्थप्रत्यय एवोपचारात् पदार्थशब्देनोच्यते यथा 'सिंहमध्यापयेदिति सिंहशब्देन माणवक इत्यदोषः । अयमत्रार्थः—केवलो ब्राह्मणशब्दः प्रयुज्यमानः प्रसिद्धिवशात् मुख्य एव ब्राह्मणार्थे प्रत्ययमादधाति, नञ्प्रयोगे तु निवृत्तपदार्थकता

ब्राह्मणशब्दस्य प्रतीयते । यथा प्रतिष्ठत इत्यत्र यद्यपि तिष्ठतिरेव गतिवचनस्तथापि तस्मिन् केवले प्रयुज्यमाने प्रस्थानं न गम्यत इति द्योतकत्वेन प्रशब्दोपेक्ष्यते तथेह नञ् ॥ पदार्थशब्देन पदार्थप्रत्यय उपचारादुच्यते ॥

(उद्द्योतः) **पदार्थनिवृत्ताविति** । पदार्थप्रत्ययनिवृत्तावित्यर्थः । स्वशक्त्यारोपितत्वबोधेऽपि ब्राह्मणादिपदानां स्वशक्त्यार्थबोधकत्वनिवृत्तिर्वचनं विना न शक्या किं च वचनेनापि तत्कर्तुमशक्यमित्युपहासः ॥ भाष्ये—**पदार्थो निवर्तयतीत्यस्य** पदार्थप्रत्ययानित्यर्थः ॥ अमुमेवार्थं शङ्कापूर्वकं दर्शयति—**नन्वित्यादिना** ॥ ननु शब्दस्य पदार्थनिवृत्तिकरत्ववत्तत्प्रत्ययनिवृत्तिकरत्वमप्यनुपपन्नम्, किं चैवमुत्तरपदार्थप्रत्यय एव न स्यादित्यत आह—**अयमत्रार्थ इति** ॥ **निवृत्तपदार्थकतेति** । निवृत्तमुख्यप्रवृत्तिनिमित्तप्रत्यायकत्वस्यारोपितप्रवृत्तिनिमित्तकप्रत्यायकतेत्यर्थः ॥ पुनर्दोक्ष्यायोक्तमेव स्मारयति—**पदार्थशब्देनेति** ॥

(प्रथमपक्षाभ्युपगमभाष्यम्)

एवं तर्हि—स्वाभाविकी निवृत्तिः ॥

(आक्षेपस्मारणभाष्यम्)

ननु चोक्तम्—किं नञ् प्रयुज्यमानः करोतीति ॥

(समाधानभाष्यम्)

नञ् प्रयुज्यमानः पदार्थं निवर्तयति । कथम्? । कीलप्रतिकीलवत् । तद्यथा—कील आहन्यमानः प्रतिकीलं निर्हन्ति ॥

(प्रदीपः) कथं पुनः स्वहेतोरुत्पद्यमानः पदार्थप्रत्ययो नञा निवर्त्यत इत्याह—**कीलप्रतिकीलवदिति** । यथा महता कीलेन प्रतिकील उत्खन्यते । तथा क्षत्रिये सादृश्यादिनिमित्तोत्पन्नस्य ब्राह्मणप्रत्ययस्य नञ्प्रयोगे निवृत्तिरित्यर्थः ॥

(उद्द्योतः) **ब्राह्मणप्रत्ययस्य** । मुख्यब्राह्मणप्रत्ययस्येत्यर्थः । अनेन द्योतकानां प्रसिद्धार्थशक्त्यनुद्बोधपूर्वकमर्थान्तरशक्त्युद्बोधकत्वं स्वभाव इति बोधितम् । तच्छक्त्यनुद्बोधेनैव तत्पदार्थप्रत्ययनिवृत्तिरिति बोध्यम् ॥

(आक्षेपभाष्यम्)

यद्येतन्नञो माहात्म्यम्, स्याद्—न जातु चिद्राजानो हस्त्यश्वं बिभृयुः, नेत्येव राजानो ब्रूयुः ॥

(प्रदीपः) इतरो यथोक्तमभिप्रायमप्रतिपद्य पदार्थ एव नञा निवर्त्यत इति ज्ञात्वा पर्यनुयुङ्क्ते—**यद्येतदिति** । प्रतिपक्षनिवारणाय नञमेव प्रयुञ्जीरन् न तु तदर्थं हस्त्यश्वादि बिभृयुरित्यर्थः ॥

(उद्द्योतः) **अभिप्रायमप्रतिपद्येति** । केचित्तु यदि नञः शब्दस्य बोधकतासामर्थ्यनिवृत्तिद्योतकत्वं स्यात्तदा तदर्थगतयोद्धृत्वादिसामर्थ्यनिवृत्तिद्योतकत्वमपि स्यादिति भाष्याशयमाहुः ॥

(सिद्धान्तपक्षाभ्युपगमभाष्यम्)

एवं तर्हि स्वाभाविकी निवृत्तिः ॥

(प्रदीपः) इदानीमभिप्रायं स्पष्टयितुमाह—**एवं तर्हीति** ॥

(आक्षेपस्मारणभाष्यम्)

ननु चोक्तम्—किं नञ् प्रयुज्यमानः करोतीति ॥

(समाधानभाष्यम्)

नञ्निमित्ता तूपलब्धिः । तद्यथा—सत्यन्धकारे द्रव्याणां समवस्थितानां प्रदीपनिमित्तं दर्शनम् । न च तेषां प्रदीपो निर्वर्तको भवति ॥

(प्रदीपः) **नञ्निमित्तेति** । क्षत्रियादौ सादृश्यनिमित्तमध्यारोपितं ब्राह्मण्यं न तु तात्त्विकमिति नञ्प्रयोगेण द्योत्यत इत्यर्थः ॥

(उद्द्योतः) ब्राह्मण्यनिवृत्तेर्नञाऽनभिधानात् **नञ्निमित्ते**त्यनुपपन्नमित्यत आह—**क्षत्रियादाविति** । तादृशब्राह्मण्यप्रवृत्तिनिमित्तकोऽसात् बोध इति भावः ॥ अयमाशयः—तत्तदर्थकाः शब्दा भिन्नाश्च । नञ्समभिव्याहारे तु तदर्थकोऽयमिति ज्ञायते, इदमेव नञो द्योतकत्वम् ॥ **नञ्निमित्ता तूपलब्धिरिति** भाष्यस्य तत्समभिव्याहारे मुख्यब्राह्मणार्थको नायम् , किं तु आरोपिततदर्थकोऽयमित्युपलब्धिर्निर्णय इत्यर्थः ॥ तदर्थगतयोद्धृत्वादिसामर्थ्यनिवृत्तिद्योतकता तु नास्य स्वभावादेवेति तात्पर्यम् । आरोपितत्वस्य नञ्वाच्यत्वे तु मुख्यब्राह्मणत्ववति गृहीतशक्तिकब्राह्मणपदार्थे तदन्वयो दुरुपपाद इति तदर्थप्रत्ययत्यागो वाच्यः । स चाशक्यः शब्दार्थसंबन्धस्य नित्यत्वहानिश्चेति दिक् ॥

(आक्षेपभाष्यम्)

यदि पुनरयं निवृत्तपदार्थकः, ब्राह्मणशब्दः किमर्थं प्रयुज्यते? ॥

(प्रदीपः) **यदि पुनरिति** । अर्थप्रत्यायनाय शब्दः प्रयुज्यते । स चेन्निवृत्तः, किमर्थमसौ प्रयुज्यते ॥

(उद्द्योतः) अमुमेवार्थं पुनः प्रश्नप्रतिवचनाभ्यां स्पष्टीकरोति—**यदि पुनरित्यादिना** ॥ **स चेन्निवृत्त इति** । ब्राह्मणपदशक्यं यन्मुख्यं ब्राह्मण्यं तस्य निवृत्तौ स्वशक्यस्य बोध्यस्याभावात् तत्प्रयोगो व्यर्थः । अशक्यबोधने तु नञ्मात्रेणापि तदर्थबोधसंभव इति भावः ॥

(समाधानभाष्यम्)

एवं यथा विज्ञायेत—अस्य पदार्थो निवर्तत इति । नेत्युक्ते संदेहः स्यात्—कस्य पदार्थो निवर्तत इति । तत्रासंदेहार्थो ब्राह्मणशब्दः प्रयुज्यते । एवं चैतत् ॥

(प्रदीपः) **एवं यथेति** । प्रतिषेधविषयप्रदर्शनाय बुद्ध्या ब्राह्मणार्थं निरूप्य तस्य क्षत्रियादौ मुख्यसत्ताविरहप्रतिपादनाय नञ्सहितो ब्राह्मणशब्दः प्रयुज्यत इत्यर्थः ॥

(उद्द्योतः) **प्रतिषेधविषयेति** । नञो द्योतकतया समभिव्याहृतपदशक्त्युद्बोधकत्वं वाच्यं तच्च पदान्तरप्रयोगं विना न संभवतीति तत्पदोपादानमिति तात्पर्यार्थः । अस्य पदस्य मुख्योर्थः प्रवृत्तिनिमित्तरूपो निवृत्तः गौणश्चोपजात इति विज्ञायेतेति तु भाष्याक्षरार्थः ॥ भाष्ये—**नेत्युक्ते संदेहः स्यादिति** । समभिव्याहृतपदस्य बोधकस्याभावात् निवृत्तिरूपार्थस्य प्रतियोग्याकाङ्क्षाया अनिवृत्तेरबोधकत्वेन च तदप्रयोग एव स्यात् । नन्वस्तु वाचकत्वमेवेति चेदेवमपि संदेहः स्यादिति भावः । तदाकारं दर्शयति—**कस्य पदार्थ इति** । कस्य पदस्य पदार्थ इत्यर्थः । अभिधेयपरः पदार्थशब्द इति तात्पर्यम् ॥ संदेहपदेन निर्णयाभावो विवक्षित इति तत्त्वम् ॥ **एवं चैतदिति** । एवमेवैतदित्यर्थः । लक्षणाप्यसन्त्रये इयमेव, यत आरोपितप्रवृत्तिनिमित्तकस्य बोधः । तत्र नञ्समभिव्याहारे निवृत्तमुख्यब्राह्मण्यको ब्राह्मणशब्दार्थ इति बुद्धे आरोपिततत्कार्यकत्वं फलतीति बोध्यम् ॥

(समाधानान्तरभाष्यम्)

अथ वा सर्वे एते शब्दा गुणसमुदायेषु वर्तन्ते ब्राह्मणः क्षत्रियो वैश्यः शूद्र इति ॥

तपः श्रुतं च योनिश्चेत्येतद् ब्राह्मणकारकम् ॥
तपःश्रुताभ्यां यो हीनो जातिब्राह्मण एव सः ॥१॥

तथा गौरः शुच्याचारः पिङ्गलः कपिलकेश इत्येतानप्यभ्यन्तरान् ब्राह्मण्ये गुणान् कुर्वन्ति ॥ समुदायेषु च वृत्ताः शब्दा अवयवेष्वपि वर्तन्ते । तद्यथा—पूर्वे पञ्चालाः । तैलं भुक्तम् । घृतं भुक्तम् । शुक्लो नीलः कपिलः कृष्ण इति । एवमयं समुदाये ब्राह्मणशब्दः प्रवृत्तोऽवयवेष्वपि वर्तते जातिहीने गुणहीने च । गुणहीने तावत्—'अब्राह्मणोयम् यस्तिष्ठन् मूत्रयति' 'अब्राह्मणोयं, यस्तिष्ठन्भक्षयति' ॥ जातिहीने संदेहाद् दुरुपदेशाच्च ब्राह्मणशब्दो वर्तते । संदेहात्तावद्गौरं शुच्याचारं पिङ्गलं कपिलकेशं दृष्ट्वाध्यवस्यति ब्राह्मणोयमिति । तत उपलभते नायं ब्राह्मणः=अब्राह्मणोयमिति । तत्र संदेहाद् ब्राह्मणशब्दो वर्तते । जातिकृता चार्थस्य निवृत्तिः ॥ दुरुपदेशाच्च । दुरुपदिष्टमस्य भवति अमुष्मिन्नवकाशे ब्राह्मणस्तमानयेति । स तत्र गत्वा यं पश्यति तमध्यवस्यति ब्राह्मणोयमिति । ततश्च पश्चादुपलभते नायं ब्राह्मणः=अब्राह्मणोयमिति [निर्ज्ञातं तस्य भवति] । तत्र दुरुपदेशाच्च ब्राह्मणशब्दो वर्तते । जातिकृता चार्थस्य निवृत्तिः ॥ अतश्च संदेहाद् दुरुपदेशाद्वा । न ह्ययं कालं माषराशिवर्णमापणे आसीनं दृष्ट्वाध्यवस्यति ब्राह्मणोयमिति निर्ज्ञातं तस्य भवति ॥

(प्रदीपः) **सर्वे इति** । तत्र यस्यैव गुणस्य स्वाभाविकी निवृत्तिस्तस्यैवासौ नञा द्योत्यते । अवशिष्टानां तु गुणानामर्थात्सद्भावो गम्यते । गुणशब्देन चात्र धर्ममात्रं पराश्रयमुच्यते ॥ स्मृतिशास्त्राश्रयेण निदर्शनाय ब्राह्मणस्य गुणानाह—**तप इति** । **तपश्चान्द्रायणादिकर्म** । **श्रुतं** वेदवेदाङ्गादीनामध्ययनम् । **योनिर्ब्राह्मणाद्** ब्राह्मण्यां जन्म ॥ **ब्राह्मणकारकमिति** । शेषषष्ठीसमासः ब्राह्मणव्यपदेशस्य तत्कारकं निमित्तमित्यर्थः ॥ गुणसमुदायाभावेपि तदेकदेशे प्रयोगदर्शनादाह—**तपःश्रुताभ्यामिति** । अधुना लोकप्रसिद्धान् बाहुल्येन तथा दृष्टान् गुणानाह—**गौर इति** ॥ **पूर्वे पञ्चाला इति** । अवयवे समुदायरूपारोपाच्छब्दप्रवृत्तिर्विज्ञेया न तु शब्दः स्वार्थं परित्यज्यार्थान्तरं वक्तुं समर्थः शब्दार्थसंबन्धस्यानित्यताप्रसङ्गात् ॥ **तैलमिति** । यदा संस्कारादियुक्तं विशिष्टमात्रापरिमितं समुदायमाह तैलशब्दस्तदा समुदायवचनोऽन्यदा तु जातिशब्द एवायम् ॥ **शुक्ल इति** । स्वयमशुक्लोप्यवयवः शुक्लावयवान्तरासादितशौक्ल्यसमुदायरूपारोपेण शुक्लशब्दाभिधेयस्तदेदमुदाहरणम् । स्वयं त्ववयवस्य शौक्ल्ये मुख्य एव शुक्लशब्दः ॥ **यस्तिष्ठन्निति** । तपःश्रुतयोरभावान्निन्दयात्राऽब्राह्मणशब्दप्रयोगस्तत्र जातिमात्रे अवयवे समुदायरूपारोपाद्ब्राह्मणशब्दप्रयोगो नञा तु स्वाभाविकी तपःश्रुतनिवृत्तिर्द्योत्यते । न च भिन्नविषयत्वं पूर्वपदोत्तरपदयोराशङ्कनीयम् । द्वयोरपि समुदायविषयत्वात्तदेकदेशनिवृत्तिसद्भावप्रतिपादनद्वारेण ॥ **जातिहीने इति** । तत्र स्तुत्या ब्राह्मणशब्दस्य प्रवृत्तिरध्ययनादिगुणसद्भावप्रतिपादनाय ॥ **संदेहादिति** । संदेहनिमित्तं गुणः संदेहशब्देनोक्तः गुणैकदेश-

दर्शनाच्च गुणसमुदायस्य संनिधिमवसाय यदा प्रमाणान्तरेण जात्यभावं प्रतिपद्यते तदा तद्द्योतनाय नञं प्रयुङ्क्तेऽब्राह्मणोयमिति ॥ **जातिकृतेति** । जात्यभावकृतेत्यर्थः । यथा वर्षकृतं दुर्भिक्षमिति ॥ **अर्थस्येति** । समुदायस्येत्यर्थः ॥ अयमत्रार्थः—एकदेशविगमात्समुदायो निवृत्त उच्यते एकदेशान्तरसद्भावाच्च तस्य सद्भावोभिधीयते । यथैकदेशकरणाकरणाभ्यां कृताकृतः संघात उच्यते ॥ **माषराशिवर्णमिति** । कालत्वविशेषप्रतिपादनपरमेतत् ॥ **आपणआसीनमिति** । आचाराभावकथनम् ॥ **निर्ज्ञातमिति** । भ्रान्तिबीजाभावाद् यथास्थितं वस्तुतत्त्वं तस्य ज्ञातमिति ब्राह्मण्यारोपाभावाद् ब्राह्मणशब्दस्य तत्राप्रयोगादब्राह्मणशब्दस्यापि प्रयोगाभाव इत्यर्थः ॥

(उद्द्योतः) इदानीं प्रकारान्तरेणापि नञो द्योतकत्वं व्युत्पादयति—भाष्ये—**अथ वा सर्वएते इति** ॥ **अवशिष्टानामिति** । तथा च तद्गुणप्रतिपादनाय ब्राह्मणशब्दप्रयोगः, निवृत्तगुणानां निवृत्तिप्रतिपादनाय च नञ्प्रयोग इत्यर्थः । अयमेव **एवमयंसमुदायेत्या**दिभाष्यार्थः ॥ एवं च गुणसमुदायवति शक्तस्य ब्राह्मणशब्दस्यार्थे कतिपयगुणाभावप्रतिपादको नञिति भावः ॥ तपःश्रुतादिसंग्रहायाह—**गुणशब्देनेति**॥ याजनादिसंग्रहायाह—**निदर्शनायेति** ॥ **कर्तरि चेति** समासनिषेधमाशङ्क्याह—**शेषषष्ठीसमास इति** ॥ एषां ब्राह्मणोत्पादकत्वाभावादाह—**व्यपदेशस्येति** ॥ **गुणसमुदायाभाव इति** । तत्र गौणः प्रयोग इत्यत्र जातिपदवन्नञपि कश्चित्तात्पर्यग्राहक इति भावः ॥ **बाहुल्येनेति** । तथा चैते गुणा व्यभिचारिण इति भावः ॥ **पिङ्गलकपिलकेश** इति भाष्ये एकं पदं, पिङ्गलाः कपिलाः केशा यस्येत्यर्थः । यद्वा पिङ्गल इति वर्णः । **गौर** इत्यस्य तु—

'अष्टवर्षा तु या दत्ता श्रुतशीलसमन्विते ।
सा गौरी तत्सुतो यस्तु स गौरः परिकीर्तितः ॥

इत्यर्थः ॥ **ब्राह्मण्ये** ब्राह्मणशब्दार्थगुणसमुदाये ॥ **कुर्वन्ति के** चिल्लौकिका इत्यर्थः ॥ **पूर्वे पश्चाला** इत्यादि ग्रन्थः परपशायां व्याख्यातः ॥ भाष्ये—**जातिहीने** इत्यादि सामान्येनैकवचनम् । तेनावयवेष्विति प्रागुक्तेन सामानाधिकरण्यमुपपन्नम् ॥ **न च भिन्नविषयत्वमिति** । नञा यत्किंचिद्विषयनिवृत्तेर्ब्राह्मणपदेन यत्किंचिद्गुणसत्त्वस्य प्रतिपादनेन पूर्वोत्तरपदयोरसामर्थ्यात्समासो न स्यादिति भावः ॥ **द्वयोरपीति** । एकदेशनिवृत्त्यादिद्वारा समुदायस्यैव निवृत्त्यादिप्रतिपादनादस्त्येव सामर्थ्यमिति भावः ॥ नञ्समभिव्याहारे श्रुतादिगुणनिवृत्तिद्योतनद्वारा जन्मनिमित्तो ब्राह्मणशब्द इति फलतोऽनेकविषयत्वमित्यत्र तात्पर्यम् ॥ जात्यारोपस्य निमित्तफले आह—**तत्र स्तुत्येति** ॥ भाष्ये—**दृष्ट्वाध्यवस्यतीति**। अध्यवसायाकारो **ब्राह्मणोय**मिति ॥ **तत उपलभते नायं ब्राह्मण** इति प्रत्यक्षमुक्तम् । तस्य चारोपमूलकता दर्शिता ब्राह्मणत्वाध्यवसायोत्तरत्वोक्त्या ॥ **अब्राह्मणोयमितीति** । अस्य **तत** इत्यादिः ॥ **प्रयुङ्क्ते**इति शेषः ॥ अर्थैकदेशस्येति वक्तव्येऽर्थस्येत्ययुक्तमत आह—**अयमत्रार्थ इति** ॥ **एकदेशविगमादिति** । एवं चोभयप्रतिपादनायोभयप्रयोग इति भावः ॥ भाष्ये—**दुरुपदेशादिति** । असम्यगुपदेशादिति तदर्थः । एतद्भाष्ये **अब्राह्मणोय**मित्युत्तरं **निर्ज्ञातं तस्य भवतीत्य**पाठोनुपयोगात् ॥

(फलान्तरसंग्रहभाष्यम्)

इदं खल्वपि भूय उत्तरपदार्थप्राधान्ये सति संगृहीतं भवति ॥ किम्? । अनेकमिति ॥ किमत्र संगृहीतम्? । एकवचनम् ॥

(प्रदीपः) तत्रैवं दोषपरिहारादुत्तरपदार्थप्रधानत्वं स्थापितम् । इदानीं तत्रैवोपचयमाह—**इदं खल्वपीति** । अनेकमित्युत्तरपदार्थप्रधानत्वे सति प्रधानगतसंख्याश्रयमेकवचनं सिध्यति नान्यथेत्यर्थः ॥

(उद्द्योतः) **नान्यथेति** । पूर्वपदार्थप्राधान्ये भिन्ने एकत्वानवगतेरेकवचनं न सिध्यतीत्यर्थः । एवमन्यपदार्थप्राधान्येपि तदसिद्धिः ॥

(आक्षेपभाष्यम्)

कथं पुनरेकस्य प्रतिषेधे [द्वि]बहूनां संप्रत्ययः स्यात्? ॥

(प्रदीपः) **कथं पुनरिति** । अनेकशब्दो यदि बहूनां वाचकस्तदा बहुवचनं प्राप्नोति । अथैकत्वप्रतिषेधमात्रमस्यार्थस्तदाऽनेको जन आगत इति बहूनां संप्रत्ययो न प्राप्नोति ॥

(उद्द्योतः) **एकप्रतिषेधमात्रमिति** । एको न भोजनीय एको जनो नागत इत्येवंरूप इत्यर्थः ॥ **बहूनां सं[प्रत्य]य इति** । एको नागत इत्येव प्रतीतेरिति भावः । ज्ञापकात् प्रसज्यप्रतिषेधेपि नञ्समासो जायत इत्यभिप्रायः ॥ **एकत्वप्रतिषेधमात्रमिति** पाठोऽपाठः ॥

(समाधानभाष्यम्)

प्रसज्यायं क्रियागुणौ ततः पश्चान्निवृत्तिं करोति । तद्यथा—आसय शायय भोजय अनेकमिति ॥

(प्रदीपः) **प्रसज्यायमिति** । विधायेत्यर्थः । निराश्रययोश्च तयोरसंभवादनियतसंख्यद्रव्याक्षेपे सत्येकप्रतिषेधाद्बहूनां प्रतीतिरित्यर्थः । एतच्च प्रसज्यप्रतिषेध उच्यते । पर्युदासे तु द्व्यादिसंख्यायुक्त एवानेकशब्दस्यार्थः । यस्माद् द्व्यादिष्वेकत्वमारोप्य प्रतिषेध्यते यथा क्षत्रियादौ ब्राह्मणत्वम् । ततो यथा अब्राह्मणः क्षत्रियादिरुच्यते तथा अनेकशब्देन संख्यान्तरयुक्तः ॥

(उद्द्योतः) भाष्ये—**क्रियागुणाविति** । गुणोदाहरणं अनेकस्मिन्रूपं रस इत्यादि ॥ एकं न भोजयेत्येकनिषेधाय प्रसञ्जनस्य चारितार्थ्यात् कथं बहुत्वावगतिरत आह—**निराश्रययोरिति** । गुणक्रिययोरित्यर्थः ॥ **एतच्च प्रसज्येति** । एवं च तदाश्रयेणैकदेशिनः शङ्कायां तमभ्युपेत्यैव प्रसज्यप्रतिषेधपदार्थं निर्णेतुमुत्तरमुक्तमिति भावः ॥ **तथानेकशब्देनेति** । आरोपितैकत्ववानित्यर्थः ।

एवं च पर्युदासपक्षे बहूनां प्रतीतिः सुलभैवेति भावः । तत्र द्वित्र्यादिनिर्णयस्तु तात्पर्यवशादिति बोध्यम् । आरोपितैकत्ववत्त्वेनैव बोधाच्चैकवचनसिद्धिः । एवं चानेके इति बहुवचनमसाध्वेवेति बोध्यमिति मञ्जूषायां विस्तरः ॥

(आक्षेपभाष्यम्)

यद्यपि तावदत्रैतच्छक्यते वक्तुं यत्र क्रियागुणौ प्रसज्येते । यत्र तु खलु पुनर्न प्रसज्येते तत्र कथम्—अनेकं तिष्ठतीति? ॥

(प्रदीपः) **यत्र तु खल्विति** । यत्र तु पूर्वमेव प्रतिषेधः पश्चात् क्रियागुणविधानं तत्र कथं बहूनां संप्रत्यय इति प्रश्नः ॥

(उद्द्योतः) **यत्र तु पूर्वमेवेति** । तत्र पूर्वं क्रियोपस्थित्यभावाद् नियतसंख्यद्रव्याक्षेपाभावेनैको न तिष्ठतीत्येव बोधपर्यवसानादिति भावः ॥

(समाधानभाष्यम्)

भवति चैवंजातीयकानामप्येकस्य प्रतिषेधेन बहूनां संप्रत्ययः । तद्यथा—न न एकं प्रियम्' 'न न एकं सुखमिति ॥

(प्रदीपः) **भवतीति** । अयमर्थः—आख्यातस्य पश्चात्प्रयोगोस्तु पूर्वं वा । धात्वर्थेन तावत्कारकस्याक्षेपोवश्यंभावीति तत्रैकप्रतिषेधसामर्थ्यादेव द्वित्वादियोगिसाधनाक्षेपः ॥ **न न इति** । **आबाधे चेति** द्विर्वचनम् । शत्रोः प्रियेण सुखेन च प्रयोक्तुराबाधा । न इति वा षष्ठी । अत्रैकप्रतिषेधसामर्थ्यादेव संख्यान्तरयुक्तवस्तुप्रतीतिः । अन्यथा न प्रियमित्येव वाच्यं स्यात् । तस्माद्यत्र वाक्येपि सामर्थ्यात्संख्यान्तरगतिर्भवति तत्र समासे वाक्यविलक्षणधर्मप्रादुर्भावहेतौ किं न भविष्यतीत्युक्तं भवति ॥

(उद्द्योतः) **न न एकमि**त्यत्र द्वयोर्नञोः प्रकृतार्थगमकत्वात् प्रियस्यैकत्वमेव प्रतीयेत न बहुत्वमत आह—**आबाधे इति** ॥ **षष्ठीति** । आबाधाया अप्रतीतेस्तत्प्रतीतेरनुपयोगाच्चेति भावः । **नोस्माकमेकं प्रियं न किं त्वनेकमिति** तदर्थः । एवमेको न तिष्ठतीत्यादावेकस्थितिनिषेधेपि अनेकस्थितिबोधो द्रष्टव्यः ॥

(भावप्रत्यये स्वरदोषपरिहाराधिकरणम्)

(आक्षेपभाष्यम्)

इहाब्राह्मणत्वमब्राह्मणता परत्वात् त्वतलौ प्राप्नुतः ॥ तत्र को दोषः? । स्वरे हि दोषः स्यात् । अब्राह्मणत्वमित्येवं स्वरः प्रसज्येत । अब्राह्मणत्वमिति चेष्यते ॥

(समाधानभाष्यम्)

नञ्समासे भाववचने उक्तम् । किमुक्तम्? । *त्वतल्भ्यां नञ्समासः पूर्वविप्रतिषिद्धं त्वतलोः स्वरसिद्ध्यर्थम् * इति ॥ नञ् ॥ ६ ॥

(प्रदीपः) **अब्राह्मणत्वमिति** । न ब्राह्मणस्य भाव इति युगपद्भावप्रतिषेधसंबन्धविवक्षायां प्रत्ययसमासप्रसङ्गे यदि परत्वात् प्रत्ययः स्यात्, पुनःप्रसङ्गविज्ञानाच्च पश्चान्नञ्समासः क्रियते, तदा **तत्पुरुषे तुल्यार्थे**ति पूर्वपदप्रकृतिस्वरेणाद्युदात्तं पदं स्यात्, प्रत्ययस्वरश्चेष्यत इति नञ्समासे तु कृते त्वतलौ कार्यौ । तत्र भावप्रत्ययस्तावत्प्रकृत्यर्थस्य सापेक्षत्वादसामर्थ्यान्न भवति नञ्समासस्तु प्रधानस्य सापेक्षत्वाद्भवतीत्याहुः ॥ ६ ॥

(उद्द्योतः) भाष्ये—**त्वतल्भ्यामिति** । पूर्वपदार्थप्राधान्याश्रयेण वार्त्तिकारम्भः उत्तरपदार्थप्राधान्ये तु असामर्थ्यात् पूर्वं भावप्रत्ययानुत्पत्तिरेवेति तत्सूत्रे भाष्ये स्पष्टम् तदाह—**तत्र भावेति** ॥ ६ ॥

(२७२ तत्पुरुषसंज्ञासूत्रम् ॥ २ । २ । १ आ. ६)

४२७ ईषदकृता ॥ २।२।७ ॥

(इष्टानुपपत्तिनिराकरणाधिकरणम्)

(१३४५ समासविधानवार्तिकम् ॥ १ ॥)

॥ * ॥ ईषद् गुणवचनेन ॥ * ॥

ईषद् गुणवचनेनेति वक्तव्यम् । अकृतेति ह्युच्यमाने इह च प्रसज्येत—ईषद्गार्ग्यः, इह च न स्यात्—ईषत्कडार इति ॥ ईषद् ॥ ७ ॥

(प्रदीपः) **ईषत् ॥ ७ ॥ ईषद्गार्ग्य इति** । यथैकार्थसमवेतक्रियागुणापेक्षया जातेः प्रकर्षादियोगः गार्ग्यतरो गार्ग्यकल्पो गार्ग्यपाश इति तथेषदर्थेनापि योगः ॥ **ईषत्कडार इति** । **गडेः कड चे**त्यारन्प्रत्ययान्तत्वात् कृदन्तः कडारशब्दः ॥ क्रियाकारकसंबन्धस्य संप्रत्ययादकृदन्त इति केचिदाहुः । तदयुक्तम् । कृच्छब्देन हि कृत्संज्ञकः प्रत्यय उच्यते ॥ अथाप्युणादीनामव्युत्पत्तिपक्षाश्रयणादत्र समासः स्यात् तथापीषद्भुक्त ईषदुन्नत इत्यत्र न स्यात् ॥ ७ ॥

(उद्द्योतः) **ईषद् ॥ ७ ॥** ननु जातावीषदर्थान्वयासंभवादेवासमासः सिद्धोत आह—**यथैकेति** । **गोत्रं चे**ति गार्ग्यत्वस्य जातित्वम् ॥ **गडेरिति** । **कडमदे** इति भ्वादौ पठितादारन्यपि सिध्यति ॥ **यद्यपीति** । उणादयो बहुलमिति शास्त्रारम्भात्सर्वमौणादिकमव्युत्पन्नमिति नियम इति भावः ॥ ७ ॥

(२७३ तत्पुरुषसंज्ञासूत्रम् ॥ २ । २ । १ आ. ७)

४२८ षष्ठी ॥ २।२।८ ॥

(इष्टानुपपत्तिनिराकरणाधिकरणम्)

(१३४६ समासप्रतिप्रसववार्तिकम् ॥ १ ॥)

॥ कृद्योगा च ॥ * ॥

कृद्योगा च षष्ठी समस्यत इति वक्तव्यम् । इध्मप्रव्रश्चनः । पलाशशातनः ॥

(आक्षेपभाष्यम्)

किमर्थमिदमुच्यते ? ॥

(प्रदीपः) **षष्ठी ॥ ८ ॥ किमर्थमिति** । सूत्रेणैवात्र समासः सिद्ध इति प्रश्नः ॥

(समाधानभाष्यम्)

***प्रतिपदविधाना च षष्ठी न समस्यते* इति वक्ष्यति । तस्यायं पुरस्तादपकर्षः ॥**

(प्रदीपः) **अपकर्ष इति** । अपवाद इत्यर्थः ॥

(उद्योतः) **षष्ठी ॥ ८ ॥** भाष्ये—**वक्ष्यतीति** । **न निर्धारणे** इत्यत्रेति शेषः ॥ उत्कर्षप्रतिद्वन्द्व्यर्थकापकर्षशब्दस्यानन्वयादाह—**अपवाद इतीति** । अपकृष्यतेऽनेनोत्सर्ग इत्यपकर्षोऽपवाद इत्यर्थः ॥

(आक्षेपभाष्यम्)

का पुनः षष्ठी प्रतिपदविधाना, का च कृद्योगा?॥

(प्रदीपः) **का पुनरिति** । प्रतिपदविधानायामपि समासप्रतिषेधविषये कृद्योगास्ति कृद्योगायामपि प्रतिपदविधानमिति विषयविभागाज्ञानात् पृच्छति ॥

(उद्योतः) **प्रतिषेधविषये** । सर्पिषो ज्ञानमित्यादौ ॥

(समाधानभाष्यम्)

सर्वा षष्ठी प्रतिपदविधाना शेषलक्षणां वर्जयित्वा ! "कर्तृकर्मणोः कृति" इति तु या षष्ठी सा कृद्योगा ॥

(प्रदीपः) **सर्वा षष्ठीति** । साक्षाद्धातुकारकविशेषोपादानेन विधानात् प्रतिपदविधानेत्यर्थः । कृच्छब्दोपादानेन तु या विहिता सैव कृद्योगोच्यते । तत्र शेषविवक्षायां **षष्ठी शेष** इत्यनेनैव सिद्धायां षष्ठ्यां **ज्ञोविदर्थस्य करण** इत्यादिप्रकरणं समासनिवृत्त्यर्थमेवारब्धम् । षष्ठी भवत्येव श्रूयते एव, न तु तस्याः समासो भवतीत्यर्थः । समासे हि सति तस्या अभावः स्यात् । तस्मात्**प्रतिपदविधाने**ति न वक्तव्यम् । तस्मिन्ननुच्यमाने **कृद्योगे**ति न वक्तव्यम् । अशेषविषये विधानार्थत्वात् **कर्तृकर्मणोः कृती**त्यस्य समासनिवृत्तौ सामर्थ्याभावात् सूत्रेणैव समासस्य सिद्धत्वात् ॥

(उद्योतः) **कारकविशेषेति** । **कर्तृकर्मणो**रित्येवमित्यर्थः ॥ **इत्यादि प्रकरणमिति** । तत्र शेष इत्यनुवृत्तेरिति भावः ॥ **शेषलक्षणा**मित्यस्य शेषमात्रलक्षणामित्यर्थ इति तात्पर्यम् ॥ **समासनिवृत्त्यर्थमेवेति** । तत्तद्धातुयोगे उपात्तकारकातिरिक्तकारकाणां शेषत्वाविवक्षाभावज्ञापनेऽपि चारितार्थ्यसंभवादिदं चिन्त्यम् । किञ्च लुगभाव एव कल्प्येत । यदि स्वेतद्वार्त्तिकत्वात्समासाभावकल्पनं तदा तद्वावश्यकमेव । सूत्राण्यपि तत्रानुवादायावश्यकानीति **न वक्तव्यं प्रतिपदविधाने**तीति चिन्त्यम् ॥ किञ्च तस्य वचनस्य सत्त्वे दिवस्तदर्थस्य कृत्वोऽर्थप्रयोग इत्यादिविषयेऽक्षाणां देवितेत्यादौ तृनन्ते **नलोके**ति निषेधेन **कर्तृकर्मणो**रिति षष्ठ्यभावे तेन षष्ठ्यां समासनिषेधसिद्धिः । त्वद्रीत्या तु शेषग्रहणस्य तत्र निवृत्त्या समासः स्यादित्यपि चिन्त्यम् ॥

(१३४७ समासप्रतिप्रसववार्तिकम् ॥ २ ॥)

॥ * ॥ तत्स्थैश्च गुणैः ॥ * ॥

(भाष्यम्) **तत्स्थैश्च गुणैः षष्ठी समस्यत इति वक्तव्यम् । ब्राह्मणवर्णः । चन्दनगन्धः । पटहशब्दः । नदीघोषः ॥**

(प्रदीपः) प्रतिप्रसवप्रसङ्गेनान्यदपि कथ्यते—**तत्स्थैरिति** । तच्छब्देन सन्निधानाद् गुण एव परामृश्यते । तेनायमर्थः—स्वात्मनि ये गुणाः अवस्थितास्तैः सह समासः ॥ न च स्वात्मन्यवस्थानं गुणानां संभवति, भेदनिबन्धनत्वान्मुख्यस्याधाराधेयभावस्य । सर्वस्य च गुणस्य द्रव्याश्रयत्वात् ॥ तस्मादभिधानव्यापारापेक्षया तत्स्थत्वमुच्यते । इह केचिद् गुणाः शब्देन द्रव्यान्निष्कृष्टा एव प्रत्याय्यन्ते, न तु द्रव्यस्योपरञ्जकत्वेन । यथा चन्दनस्य गन्ध इति सर्वदा वैयधिकरण्यमेव गुणगुणिनोः, न कदाचिच्चन्दनं गन्ध इति सामानाधिकरण्यं भवति । शुक्लादयस्तु गुणाः कदाचिन्निष्कृष्टरूपाः शब्दैरुच्यन्ते पटस्य शुक्ल इति । कदाचिद् द्रव्येणैकत्वमापन्नाः शुक्लः पट इति । तस्माद् द्विविधगुणसद्भावात्तत्स्थैरिति विशेषणं रूपादिगुणपरिग्रहार्थमुपात्तमिति ब्राह्मणवर्णादय उदाहरणम् ॥ अथ बलाकायाः शौक्ल्यमिति समासः कस्मान्न भवति । तत्स्थं हि शौक्ल्यम् । सर्वदा वैयधिकरण्येन संबन्धात् । नैष दोषः । शौक्ल्यशब्देन शुक्लो गुणोऽभिधीयते शुक्लशब्दस्य द्रव्ये वर्तमानस्य तस्मिन्नेव प्रवृत्तिनिमित्ते भावप्रत्ययविधानात् । न चासौ तत्स्थः । अभेदाध्यवसायेन द्रव्यं प्रत्यनुरञ्जकत्वदर्शनाच्छुक्लः पट इति । अर्थस्य च तत्स्थत्वमाश्रीयत इति शब्दभेदेऽप्यर्थस्याभेदान्नास्ति शुक्लस्य गुणस्य तत्स्थत्वम् । रूपवान् पट इत्यादौ तु नास्ति गुणगुणिनोरभेदाध्यवसायः । भेदाश्रयेणैव मत्वर्थीयप्रयोगादिति रूपस्य तत्स्थत्वमव्याहतमिति पटरूपमिति समासो भवत्येव ॥

(उद्योतः) तच्छब्देन द्रव्यपरामर्शे काकस्य कार्ष्ण्यमित्यादावतिप्रसङ्गमाशङ्क्याह—**तच्छब्देनेति** ॥ **स्वात्मनीति** । स्वात्मन्येवाभेदेनावस्थिता न तु द्रव्ये इत्यर्थः ॥ नन्वभेदस्याधाराधेयभावनियामकत्वाभावात्तत्स्थैरित्यनुपपन्नमिति शङ्कते—**न चेति** ॥ यद्यपि व्यपदेशिवद्भावेन तत्स्थैरिति वक्तुं शक्यम् । तथापि स न मुख्य इत्याह—**मुख्यस्येति** ॥ उत्तरयति—**तस्मादभिधानेति** । गुणमात्रशक्तशब्दमात्रप्रतिपाद्यगुणवाचकैः शब्दैरित्यर्थः । अत एवार्थस्य तत्स्थत्वमित्यग्रे वक्ष्यति ॥ तदेवोपपादयति—**इह केचिदिति** । **द्रव्यान्निष्कृष्टाः** भेदेनैव द्रव्यान्वयिनः । तदा हि गुणगतजातिः प्रवृत्तिनिमित्तम् ॥ **उपरञ्जकत्वं**, स्वाभेदेन द्रव्यप्रत्यायकत्वम् ॥ **द्रव्येणैकत्वमिति** । जातिविशिष्टगुणप्रवृत्तिनिमित्तं, अत

एव ततो भावप्रत्ययेन गुणबोधः ॥ अर्थस्य तत्स्थत्वमिति । एवं च गुणिपरत्ववाचकशब्दाभाववत्त्वं तात्स्थ्यमिति फलितम् ॥

(१३४८ समासनिषेधवार्तिकम् ॥ ३ ॥)

॥ * ॥ न तु तद्विशेषणैः ॥ * ॥

(भाष्यम्) **न तु तद्विशेषणैरिति वक्तव्यम् । इह मा भूत्—घृतस्य तीव्रो गन्धः । चन्दनस्य मृदुरिति ॥**

(प्रदीपः) **न तु तद्विशेषणैरिति** । तच्छब्देन गुणाः परामृश्यन्ते । तेषां गुणानां यानि विशेषणानि तद्वचनैः सह समासो न भवतीत्यर्थः ॥ **घृतस्य तीव्र इति** । तीव्रो गन्धस्य विशेषणम् । **चन्दनस्य मृदुरिति** स्पर्शस्य मृदुत्वं विशेषणम ॥ ननु घृतस्य गन्धेन संबन्धो नतु तद्गतेन तीव्रेण विशेषणेनेति सामर्थ्याभावात्समासस्य प्राप्तिरेव नास्ति तत्किं प्रतिषेधेन ॥ एवं तर्हि यदा प्रकरणादिवशात्तीव्रशब्द एव विशिष्टगन्धवृत्तिस्तदा तदर्थोपजनित एव व्यतिरेके घृतस्येति षष्ठी तदा षष्ठीति समासप्रसङ्गः । यश्च गन्धविशेषवचनस्तीव्रशब्दस्तस्य द्रव्यवाचिना सामानाधिकरण्याभावाद्गन्धशब्दस्येव तत्स्थगुणाभिधायित्वात् समासप्रसङ्गे प्रतिषेध उच्यते ॥ ननु च तीव्रं घृतं मृदु चन्दनमिति सामानाधिकरण्यदर्शनात्तत्स्थत्वाभावात् समासप्रसङ्गात्तत्प्रतिषेधोऽनर्थकः ॥ एवं तर्हि सौत्रस्य प्रतिषेधस्य विषयकथनमिदम्—**न तु तद्विशेषणैरिति** । तत्स्थत्वाभावात्तैः समासः प्रतिषिध्यत एवेत्यर्थः ॥

(उद्द्योतः) **एवं तर्हीति** । तद्विशेषणैरित्यस्य तद्विशेषप्रतिपादकैरित्यर्थ इति भावः ॥ तीव्रादिशब्दैः समासप्रसङ्गमुपपादयति—**यश्च गन्धेति** ॥ **एवं तर्हीति** । तद्विशेषणैरित्यस्य तद्विशेषप्रतिपादकैरित्यर्थात्तीव्रादयः शुक्लादयश्च निषेधसूत्रस्य विषया इत्यनेन सूच्यते इति भावः ॥

(आक्षेपभाष्यम्)

किमर्थमिदमुच्यते ? ॥

(उद्द्योतः) भाष्ये—**किमर्थमिदमिति** । इदमा व्यवहितमपि तत्स्थैरिति परामृश्यते, तदाह—**गुणेनेति** ॥

(समाधानभाष्यम्)

गुणेन नेति प्रतिषेधं वक्ष्यति तस्यायं पुरस्तादपकर्षः ॥

(आक्षेपभाष्यम्)

किं पुनः कारणं गुणेन नेत्युच्यते, न पुनर्गुणवचनेन नेत्युच्येत ? ॥

(प्रदीपः) **न पुनरिति** । तत्र गुणोपसर्जनद्रव्यवाचिना समासो निषिध्यते इति केवलगुणवाचिना रूपादिशब्देन समासो भविष्यतीत्यर्थः ॥

(उद्द्योतः) **केवलगुणेनेति** । घृतस्य तीव्र इत्यावपि केवलगुणवाच्येवेति भावः ॥

(समाधानभाष्यम्)

नैवं शक्यम् । इह हि न स्यात्—काकस्य कार्ष्ण्यं बलाकायाः शौक्ल्यमिति । एतदेव खल्वपि तस्मिन्योगे उदाहरणम् ॥ यद्धीदं ब्राह्मणस्य शुक्लाः वृषलस्य कृष्णा इति । असामर्थ्यादत्र न भविष्यति ॥ कथमसामर्थ्यम् ? । सापेक्षमसमर्थं भवतीति ॥ द्रव्यमत्रापेक्ष्यते दन्ताः ॥ तस्माद् 'गुणेन न' इति वक्तव्यम् । गुणेन नेत्युच्यमाने '*तत्स्थैश्च गुणैः*' इति वक्तव्यम् । तत्स्थैश्च गुणैरित्युच्यमाने '*न तु तद्विशेषणैः*' इति वक्तव्यम् ॥ षष्ठी ॥ ८ ॥

(प्रदीपः) **एतदेवेति** । केवलगुणवाच्येवेत्यर्थः ॥ **द्रव्यमत्रेति** । ततश्च दन्तापेक्षया ब्राह्मणस्येति षष्ठीति शुक्लार्थेन संबन्धाभावात्समासस्य प्रसङ्गाभावाद्नार्थः प्रतिषेधेन ॥ ८ ॥

(उद्द्योतः) भाष्ये—**एतदेवेति** । काकस्य कार्ष्ण्यमित्यादेव ॥ **यद्धीदमिति** यत्त्विदमित्यर्थः । **सापेक्षमसमर्थमिति** । इतरसापेक्षत्वेन शुक्ला इत्यनेनानन्वयादसामर्थ्यमित्याशयः ॥ तद् ध्वनयन्नाह—**शुक्लार्थेन संबन्धाभावादिति** ॥ **न तु तद्विशेषणैरिति** वक्तव्यमितिभाष्ये प्रतिषेधविषयप्रदर्शनार्थमित्यादिः ॥ ८ ॥

(२७४ तत्पुरुषसमासनिषेधसूत्रम् ॥ २ । २ । १ आ. ८ सू.)

४३० न निर्धारणे ॥ २।२।१० ॥

(अनिष्टपरिहाराधिकरणम्)

(१३४९ समासनिषेधवार्तिकम् ॥ १ ॥)

॥ * ॥ प्रतिपदविधाना च ॥ * ॥

(भाष्यम्) **प्रतिपदविधाना च षष्ठी न समस्यत इति वक्तव्यम् । इह मा भूत्—सर्पिषो ज्ञानम्, मधुनो ज्ञानम् ॥ न निर्धारणे ॥ १० ॥**

(२७५ तत्पुरुषसमासनिषेधसूत्रम् ॥ २ । २ । १ आ. ९ सू.)

४३१ पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन ॥ २।२।११ ॥

(गुणशब्दार्थनिरूपणाधिकरणम्)

(प्रदीपः) **पूरण ॥ ११ ॥** अर्थशब्दस्य प्रत्येकं संबन्धाद् गुणेति स्वरूपग्रहणं न भवति, नाप्यदेशाम् ॥ किं तर्हि ? । सत्त्वे निविशतेऽपैतीत्येतल्लक्षणलक्षितो गुणो गृह्यते । संसर्गिभेदकमित्यादिलक्षणयुक्तस्तु न गृह्यते । सामान्यादे-

रपि ग्रहणप्रसङ्गात्। नापि शुक्लादेरेव ग्रहणम्, कण्टकस्य तैक्ष्ण्यमित्यस्योदाहृतत्वात् । गोविंशतिरित्यादौ संख्यया समासो न निषिध्यते शतसहस्रान्ताच्च निष्कात् *क्रोशशतयोजनशतयोरुपसंख्यानम्* खारीशतमपि ददातीति मुनित्रयवचनाज्ज्ञापकात् । उत्तरपदार्थप्राधान्यमित्यादिश्च मुनिप्रयोगादस्य प्रतिषेधस्यानित्यत्वाच्चगौरवादिशब्दसिद्धिः ॥

(उद्द्योतः) पूरणगुण ॥ ११ ॥ सर्वेनिविंशतघृत्यादि । वस्तुत इदं चिन्त्यम् । तस्याकडारसूत्रोक्तगुणवचनपदार्थसमत्वात् तत्र बाधकः सर्वैलिङ्गानामित्युक्त्वात्काकस्य कार्ष्ण्यमित्यादेरनुदाहरणत्वप्रसङ्गात् ॥ तस्मादत्र व्याख्यानात् केवलगुणवाची सन् यो गुणिबोधकः नत्प्रकृतिकभावप्रत्ययान्तप्रतिपाद्यानां गुणपदेन ग्रहणम् अर्थपदान्यपाच्य तद्बोधकशब्दमात्रग्रहणम् । एवं च प्राधान्यगौरवादौ प्रसक्तिरेव न ॥

(गुणोदाहरणाधिकरणम्)

(आक्षेपभाष्यम्)

गुणे किमुदाहरणम् ? ॥

(प्रदीपः) गुणे किमिति । वक्ष्यमाणोऽभिप्रायः ॥

(समाधानभाष्यम्)

ब्राह्मणस्य शुक्लाः, वृषलस्य कृष्णा इति ॥

(समाधानबाधकभाष्यम्)

नैतदस्ति प्रयोजनम् । असामर्थ्यादत्र न भविष्यति । कथमसामर्थ्यम् ? । सापेक्षमसमर्थं भवतीति द्रव्यमत्रापेक्ष्यते दन्ताः ॥

(प्रयोजनान्तरभाष्यम्)

इदं तर्हि—काकस्य कार्ष्ण्यम्, कण्टकस्य तैक्ष्ण्यम्, बलाकायाः शौक्ल्यमिति ॥

(पूर्वोक्ताभ्युपगमभाष्यम्)

इदं चाप्युदाहरणम्—ब्राह्मणस्य शुक्लाः, वृषलस्य कृष्णा इति ॥

(बाधकस्मारणभाष्यम्)

ननु चोक्तम्—असामर्थ्यादत्र न भविष्यति । कथमसामर्थ्यम् ? । सापेक्षमसमर्थं भवतीति द्रव्यमत्रापेक्ष्यते दन्ता—इति ॥

(बाधकपरिहारभाष्यम्)

नैष दोषः । भवति वै कस्यचिदर्थात्प्रकरणाद्वाऽपेक्ष्यं निर्ज्ञातं तदा वृत्तिः प्राप्नोति ॥

(प्रदीपः) भवतीति । यदा प्रकरणादिवशाद्दन्ताद्यर्थ एवावसितवृत्तिः शुक्लादिशब्दस्तदा तदर्थोपजनित एव ब्राह्मणादौ व्यतिरेक इति सामर्थ्यसद्भावात्समासप्रसङ्ग इत्यर्थः ॥ ननु गुणस्य गुण्यपेक्षत्वाद् गुणिन एव समासनिषेधेन भाव्यम्, न च ब्राह्मणः शुक्लगुणाधारः ॥ नैष दोषः । गुणशब्देन केवलगुणवाचिनो गुणोपसर्जनद्रव्यवाचिनश्च व्याप्तिन्यायाश्रयेण गृह्यन्त इति गुणिनो गुणाधारसंबन्धिनश्चोपपन्नः समासप्रतिषेधः ॥

(उद्द्योतः) अवसितवृत्तिरिति । सामान्यशब्दस्यापि प्रकरणाद्विशेषमात्रोपस्थापकत्वमित्यर्थः । अनेनैतत्सूचयति वाक्यैकदेशन्यायेन शुक्ला इत्यस्य दन्ताः शुक्ला इत्यर्थः । षष्ठीत्यस्य च षष्ठ्यन्तं समर्थप्रकृतिकसुबन्तेन समस्यते इत्यर्थः । तादृशं च न शुक्ला इति पदमित्यसामर्थ्यं तदवस्थमेव ॥ एतदभिप्रायेणैव पूर्वसूत्रे एतदेवोदाहरणमित्युक्तम् । अग्रत्यं भाष्यं त्वेकदेश्युक्तिः अनेन समासशङ्कावारणायाबुधानां यतः कियत इति कर्मणि चेति सूत्रे वदता कैयटेन ध्वनितमेतत् ॥ अन्यथा ब्राह्मणस्य ग्रामं गत इत्यर्थे ग्राममित्यस्य प्रकरणादिना ज्ञाने गत इत्यस्यैव वाक्यैकदेशन्यायेन तावदर्थत्वे सामर्थ्यात्समासापत्तिरिति स्पष्टं कर्मणि चेति सूत्रे भाष्ये ॥

(सदुदाहरणनिरूपणाधिकरणम्)

(आक्षेपभाष्यम्)

सति किमुदाहरणम् ? ॥

(उदाहरणभाष्यम्)

ब्राह्मणस्य पश्यन्, ब्राह्मणस्य पक्ष्यमाणः ॥

(उदाहरणनिराकरणभाष्यम्)

नैतदस्ति । प्रतिषिध्यतेऽत्र षष्ठी 'लप्रयोगे ने'ति । या च श्रूयते । एषा वाक्यमर्थमपेक्ष्य भवति तत्रासामर्थ्यान्न भविष्यति । कथमसामर्थ्यम् ? । सापेक्षमसमर्थं भवतीति । द्रव्यमत्रापेक्ष्यते ओदनः ॥

(प्रदीपः) प्रतिषिध्यतेत्रेति । आवर्जनवाचिषष्ठ्याश्रयेण ब्राह्मणं पचः कर्म मन्यते । यथास्य लोकपक्तिर्लोकावर्जनमित्यर्थः । ततश्च ब्राह्मणस्येति षष्ठी पाकापेक्षया कर्मणि न भवतीत्यर्थः ॥

(उद्द्योतः) ननु ब्राह्मणस्य पक्ष्यन्नित्यत्र ब्राह्मणस्यौदनं पक्ष्यन्नित्यर्थावगमात् ब्राह्मणस्य पाकापेक्षया कर्मत्वकर्तृत्वाभावात् कर्तृत्वस्योक्तत्वाच्च षष्ठ्या अप्राप्तौ प्रतिषेधोक्तिरसङ्गतेत्यत आह—आवर्जनवाचीति । आवर्जनमङ्गीकारस्त्यागो वा इत्याहुः ॥ कर्मणि न भवतीति । शेषषष्ठ्यन्तस्य नामार्थान्वये संभवति क्रियान्वयो नेति भावः । एतेन कर्मणः शेषत्वविवक्षायां षष्ठी सुलभेत्यपास्तम् ॥ नलोकेत्येननिषेधविषयेऽनभिधानाच्छेषत्वविवक्षैव न भाष्यप्रामाण्यादित्यन्ये ॥

(उदाहरणान्तरभाष्यम्)

इदं तर्हि—चोरस्य द्विषन्, वृषलस्य द्विषन् ॥

(प्रदीपः) चोरस्य द्विषन्निति । तौ सदित्यत्र तौग्रहणस्योपाध्यसंसर्गार्थत्वाद् द्विषोऽमित्रइत्येतत्सूत्रविहितोऽपि शता स : ॥

(उद्द्योतः) ननु द्विषोमित्र इति विहितस्य न सत्संज्ञकत्वं लट इति सूत्रविहितयोरेव तत्संज्ञाविधानादित्याशङ्क्याह—तौस-दिति ॥

(आक्षेपभाष्यम्)

ननु चात्रापि प्रतिषिध्यते ॥

(प्रदीपः) **ननु चात्रापीति** । तृन्निति प्रत्याहारेण शतुरपि ग्रहणात् ॥

(उद्द्योतः) अस्य शतुर्लादेशत्वाभावादाह—तृनिति ॥

(समाधानभाष्यम्)

वक्ष्यत्येतद् *द्विषः शतुर्वावचनम्* इति ॥

(उद्द्योतः) अस्योदाहरणत्वं स्थापयति—भाष्ये—वक्ष्यत्येतदिति ॥

(अव्ययोदाहरणनिरूपणाधिकरणम्)

(आक्षेपभाष्यम्)

अव्यये किमुदाहरणम्? ॥

(प्रयोजनभाष्यम्)

ब्राह्मणस्योच्चैः, वृषलस्य नीचैरिति ॥

(प्रयोजननिराकरणभाष्यम्)

नैतदस्ति । असामर्थ्यादत्र न भविष्यति ॥ कथमसामर्थ्यम्? । सापेक्षमसमर्थं भवतीति । द्रव्यमत्रापेक्ष्यते आसनम् ॥

(प्रयोजनभाष्यम्)

इदं तर्हि—ब्राह्मणस्य कृत्वा, वृषलस्य कृत्वेति ॥

(प्रयोजननिराकरणभाष्यम्)

एतदपि नास्ति । प्रतिषिध्यते तत्र षष्ठी 'अव्ययप्रयोगे न' इति । या च श्रूयते एषा बाह्यार्थमपेक्ष्य भवति, तत्रासामर्थ्यान्न भवति ॥ कथमसामर्थ्यम्? । सापेक्षमसमर्थं भवतीति । द्रव्यमत्रापेक्ष्यते कटः ॥

(प्रयोजनान्तरभाष्यम्)

इदं तर्हि—पुरा सूर्यस्योदेतोराधेयः । पुरा वत्सानामपाकर्तोः ॥

(प्रदीपः) **सूर्यस्योदेतोरिति** । सूर्योदयात् पूर्वमित्यर्थः । वृक्षस्योपरीत्यादीन्यप्युदाहरणानि ॥

(उद्द्योतः) **इत्यादीन्येति** । साहचर्यात् कृदव्ययमेव गृह्यते । अन्यान्ययैः सति सामर्थ्ये समास इष्ट एवेति भाष्याशयमाहुः ॥

(आक्षेपभाष्यम्)

ननु चात्रापि प्रतिषिध्यते—'अव्ययम्' इति कृत्वा ॥

(समाधानभाष्यम्)

वक्ष्यत्येतत्—*अव्ययप्रतिषेधे तोसुन्कसुनोरप्रतिषेधः* इति ॥

(समानाधिकरणोदाहरणाधिकरणम्)

(आक्षेपभाष्यम्)

समानाधिकरणे किमुदाहरणम्? ।

(समाधानभाष्यम्)

राज्ञः पाटलिपुत्रकस्य । शुकस्य माराविकस्य । पाणिनेः सूत्रकारस्य ॥

(प्रदीपः) **राज्ञः पाटलिपुत्रकस्येति** । विशेषणसमासोऽत्र भवत्येव ततो विशेषणस्यैव पूर्वनिपातः सिद्धो भवति । षष्ठीसमासे तु पूर्वनिपातस्यानियमः स्यादिति स प्रतिषिध्यते । विशेषसमासे च वचनसामर्थ्यात्**समानाधिकरणमसमर्थवदिति** नाश्रीयते ॥

(उद्द्योतः) **पूर्वनिपातानियमः स्यादिति** । उपसर्जनत्वस्यान्वर्थतामाश्रित्य षष्ठीसमासेपि तन्नियमसंभवादुपसर्जनसंज्ञासूत्रे स्वयमपि तथैवोक्तेश्च चिन्त्यमेतत् ॥ तस्माद्विशेषणसमासोप्यत्र बाहुलकात्रैवेत्येव तत्त्वमिति कश्चित्, तन्न । अर्धपिप्पलीत्याद्यनुरोधेन तस्या अन्वर्थत्वाश्रयणमशक्यमित्याशयात् ॥ **विशेषणसमासे वचनसामर्थ्यादिति** । **पूर्वापरप्रथमचरमेति** सूत्रे **समानेत्यादि**वचनसामर्थ्यादित्यर्थः । एवं च षष्ठीसमासे तदप्रवृत्तौ मानाभावः । न चैवं बहुव्रीहिरुच्छिद्येत । शेषग्रहणसामर्थ्येन नत्राप्यस्याप्रवृत्तेः । न च सुन्दरपानक इत्यादौ तस्य सावकाशता । एवं तर्हि समानेत्यादिसामान्यापेक्षं यत्र समानाधिकरणानां विशेषविहितः समासः तत्रैतदप्रवृत्तिः ॥ समानादेश्च कृदन्तेन न समासोऽनभिधानादित्याशयः ॥

(समाधानबाधकभाष्यम्)

नैतदस्ति । असामर्थ्यादत्र न भविष्यति ॥ कथमसामर्थ्यम्? । समानाधिकरणमसमर्थवद्भवतीति ॥

(उद्द्योतः) केचित्तु **प्रथमानिर्दिष्टमिति** सूत्रभाष्योक्तरीत्या षष्ठीतिसूत्रे येन सुबन्तेन समासस्तदर्थनिरूपितसंबन्धार्थकषष्ठ्यैव गृह्यते । तादृशमेव च सामर्थ्यं षष्ठीसमासप्रवृत्तौ निमित्तम् । न चेदं सामर्थ्यं प्रकृतेस्ति, इत्याशयेनाह—**असामर्थ्यादत्र न भविष्यतीति** । एवं च प्रत्याख्यातं समानाधिकरणग्रहणम् ॥ अग्रिमभाष्यं त्वेतदाशयानभिज्ञपूर्वपक्षिसिद्धान्तिनोरेकदेशिनोरुक्तिपरमित्याहुः ॥ ११ ॥

(उदाहरणान्तरभाष्यम्)

इदं तर्हि—सर्पिषः पीयमानस्य, यजुषः क्रियमाणस्य ॥

(उदाहरणबाधकभाष्यम्)

ननु चात्राप्यसामर्थ्यादेव भविष्यति ॥ कथमसामर्थ्यम् ? । समानाधिकरणमसमर्थवद्भवतीति ॥

(उदाहरणसाधकभाष्यम्)

अधात्वभिहितमित्येवं तत् ॥ पूरणगुण ॥ ११ ॥

(प्रदीपः) अधात्वभिहितमिति । एवं च कटस्य क्रियमाणस्येत्याद्यप्युदाहरणम् ॥ ११ ॥

(२७६ तत्पुरुषनिषेधसूत्रम् ॥ २ । २ । १ आ. १० सू.)

४३४ कर्मणि च ॥ २।२।१४ ॥

(चकारस्येत्यर्थकतानिरूपणाधिकरणम्)

(आक्षेपभाष्यम्)

कथमिदं विज्ञायते—कर्मणि या षष्ठी सा न समस्यत इति । आहो स्वित्—कर्मणि यः क्तः—इति ॥ कुतः संदेहः ? । उभयं प्रकृतम् । तत्रान्यतरच्छक्यं विशेषयितुम् ॥

(प्रदीपः) कर्मणि ॥१४॥ क्तषष्ठ्योः प्रकृतत्वादन्यतरविशेषणे दोषदर्शनात् पृच्छति—कथमिति ॥

(उद्योतः) कर्मणि च ॥ १४ ॥ दोषदर्शनादिति । पक्षद्वयेपि दोषदर्शनादित्यर्थः ॥

(विशेषजिज्ञासाभाष्यम्)

कश्चात्र विशेषः ? ॥

(१३५० प्रथमपक्षे दूषणवार्तिकम् ॥ १ ॥)

॥ * ॥ कर्मणीति षष्ठीनिर्देशश्चेदकर्तरि कृता समासवचनम् ॥ * ॥

(व्याख्याभाष्यम्)

कर्मणीतिषष्ठीनिर्देशश्चेदकर्तरि कृता समासो वक्तव्यः । इध्मप्रव्रश्चनः पलाशशातनः ॥

(प्रदीपः) अकर्तरि कृतेति । यः कर्तरि विधीयते यथा कुम्भकार इति तत्र परत्वादुपपदसमासेन भाव्यम्, कचित्तु 'तृजकाभ्यां कर्तरि चे'ति प्रतिषेधेनेत्यभिप्रायेणाकर्तरीत्युक्तम् ॥ इध्मप्रव्रश्चनइति । करणे ल्युट् कर्मणि षष्ठी ॥

(उद्योतः) कचित्तु तृजकाभ्यामिति । तृजकाभ्यामित्यस्य कर्त्रर्थतृजकाभ्यामित्यर्थे इदम् ॥ कर्तरि चेत्यस्यैवायमर्थ इति वृत्तिमते आह—कर्तरित्येति । अन्यैस्त्वनुपपदकृदन्तैः शेषषष्ठ्या समासो भवत्येव गङ्गाधरभूधरादौ । स्वरेपि न विशेषः । उभयथाप्यन्तोदात्तत्वात् । न च गस्थकनि गाथकशब्देन साम्नां गायक इत्यर्थे समासानापत्तिः । शेषषष्ठ्या समासेपि स्वरे विशेषादिति वाच्यम् । अकर्तरीत्यस्य तृजकाभ्यां कर्तरीति सूत्रनिर्दिष्टभिन्नेनेत्यर्थात् कर्मणीत्यस्य षष्ठीविशेषणत्वे तेनेत्यस्यात्राननुवृत्तिरेवेति बोध्यम् ॥

(१३५१ सूत्रवैयर्थ्यापत्तिवार्तिकम् ॥ २ ॥)

॥*॥ तृजकाभ्यां चानर्थकः प्रतिषेधः ॥*॥

(भाष्यम्) तृजकाभ्यां चानर्थकः कर्तरि प्रतिषेधो भवति । अपां स्रष्टा । पुरां भेत्ता । यवानां लावकः । कर्मणीत्येव सिद्धम् ॥

(प्रदीपः) तृजकाभ्यां चेति । कर्तरि यौ तृजकौ तत्र सामर्थ्यात् कर्मण्येव षष्ठीत्यनेनैव प्रतिषेधः सिद्धः ॥

(उद्योतः) भाष्ये—तृजकाभ्यां चेति । अस्यैव कर्त्रर्थतृजकाभ्यामित्यर्थ इति भावः ॥

(द्वितीयपक्षाभ्युपगमभाष्यम्)

अस्तु तर्हि—कर्मणि यः क्त इति ॥ किमुदाहरणम् ? । ब्राह्मणस्य भुक्तं[1] वृषलस्य पीतमिति[2] ॥

(१३५२ दूषणवार्तिकम् ॥ ३ ॥)

॥ * ॥ क्तनिर्देशोऽसमर्थत्वादप्रतिषेधः ॥ * ॥

(व्याख्याभाष्यम्)

क्तनिर्देशोऽसमर्थत्वाद् अप्रतिषेधः अनर्थकः प्रतिषेधः अप्रतिषेधः ॥ समासः कस्मान्न भवति ? । असामर्थ्यात् ॥ कथमसामर्थ्यम् ? । सापेक्षमसमर्थं भवतीति । द्रव्यमत्रापेक्ष्यते[3] ओदनः ॥

(प्रदीपः) द्रव्यमत्रेति । ब्राह्मणस्येति षष्ठी भुक्तापेक्षया न भवति न लोकाव्ययनिष्ठेति प्रतिषेधात् । ततश्च ब्राह्मणस्य य ओदनादिः सोऽन्येन भुक्त इत्यर्थः प्रतीयत इति ब्राह्मणस्य भुक्तेन संबन्धाभावः ॥

(१३५३ वार्तिकम् ॥ ४ ॥)

॥ * ॥ प्रतिषेध्यमिति चेत्कर्तर्यपि प्रतिषेधः ॥ * ॥

(व्याख्याभाष्यम्)

अथैवं सति प्रतिषेधः कर्तव्य इति मन्यसे, कर्तर्यपि प्रतिषेधो वक्तव्यः स्यात्—ब्राह्मणस्य गतः ब्राह्मणस्य ज्ञात इति ॥

(प्रदीपः) प्रतिषेध्यमिति चेदिति । यदा पारम्पर्येण संबन्धसंभवाद् 'भवति वै कस्य चिद्' इति न्यायाद्वा समासशङ्कानिवारणायाबुधानां यत्नः क्रियते तदातिप्रसङ्गो यत्नस्येत्यर्थः ॥

(उद्योतः) पारम्पर्येणेति । भुजेरोदनेनौदनस्य ब्राह्मणेनेत्यर्थः ॥ भवति वै इति । ब्राह्मणस्य शुक्ला इत्यत्रोक्तो न्यायः ॥ समासशङ्कानिवारणायेति । अनेन तन्न्यायाश्रयणेपि पूरणेतिसूत्रोक्तमर्यादया वस्तुतः सामर्थ्यं नास्त्येवेति सूचयति । तदाह—

---

१ 'भुक्तः' ॥ २ 'पीत इति' ॥ ३ 'इष्यते' ॥

अबुधानामिति ॥ अतिप्रसङ्ग इति । अन्यत्राप्येवं न्यायैः समासापादनसंभवात् तत्रापि प्रतिषेधो वक्तव्य इत्यर्थः ॥ भाष्ये— ब्राह्मणस्य गत इत्यादेः ब्राह्मणस्य ग्रामं गत इत्यादिक्रमेणार्थः ॥

(१३५४ वार्तिकम् ॥ ५ ॥)

॥ * ॥ पूजायां च प्रतिषेधानर्थक्यम् ॥ * ॥

(भाष्यम्) पूजायां च प्रतिषेधोऽनर्थकः—राज्ञां पूजितः राज्ञामर्चित इति । कर्मणीत्येव सिद्धम् ॥

(१३५५ सिद्धान्तवार्तिकम् ॥ ६ ॥

॥ * ॥ तस्मादुभयप्राप्तौ कर्मणि षष्ठ्याः प्रतिषेधः ॥ * ॥

(भाष्यम्) तस्माद् "उभयप्राप्तौ कर्मणि" इत्येवं या षष्ठी तस्याः प्रतिषेधो वक्तव्यः ॥

(आक्षेपभाष्यम्)

स तर्हि वक्तव्यः ? ॥

(समाधानभाष्यम्)

न वक्तव्यः । इत्यर्थेऽयं चः पठितः—"कर्मणि च" कर्मणीत्येवं या षष्ठी ॥ कर्मणि च ॥ १४ ॥

(प्रदीपः) इत्यर्थ इति । अनेकार्थत्वान्निपातानाम् । तेन कर्मणीत्युच्चार्य या षष्ठी विधीयते सा न समस्यत इत्यर्थः । ततश्चाश्चर्यो गवां दोहो गोपालकेनेत्याद्युदाहरणम् ॥ १४ ॥

(उद्योत) इत्याद्युदाहरणमिति । ब्राह्मणस्य भुक्तो ब्राह्मणस्य गत इति पूर्वोक्ते तु असामर्थ्यादेव समासो न भवतीति हृदयम् ॥ १४ ॥

(२७७ तत्पुरुषसंज्ञासूत्रम् ॥ २ । २ । १ आ. ११ सू.)

४३७ नित्यं क्रीडाजीविकयोः २।२।१७॥

(नित्यग्रहणसंबन्धविचाराधिकरणम्)

(आक्षेपभाष्यम्)

किमिह नित्यग्रहणेनाभिसंबध्यते विधिः, आहोस्वित्—प्रतिषेधः ? ॥

(प्रदीपः) नित्यं क्री ॥ १७॥ प्रतिषेधे सिद्धेऽस्यारम्भाद्विधिरप्यत्र संभाव्यते अनन्तरत्वाच्च प्रतिषेधोपीति प्रश्नः—किमिहेति ॥

(उद्योतः) नित्यं क्रीडा ॥ १७ ॥ प्रतिषेधे सिद्धइति । जीविकाविषये सुखकाम्यामित्यनेन कर्तरि चेत्यनेन वेति भावः ॥

(समाधानभाष्यम्)

विधिरित्याह ॥ कुत एतत् ? । विधिर्हि विभाषा, नित्यः प्रतिषेधः ॥ नित्यम् ॥ १७ ॥

(प्रदीपः) विधिर्हीति ॥ महाविभाषाधिकारात् ॥ नित्य इति । विधिविकल्पेनैव पाक्षिकस्य प्रतिषेधस्य सिद्धत्वात् प्रतिषेधारम्भसामर्थ्यादेव नित्यः प्रतिषेधः सिद्ध इति किं नित्यग्रहणेनेत्यर्थः ॥ १७ ॥

(उद्योतः) नित्यप्रतिषेध इति । प्रतिषेधवाक्यैकविषये व्यपेक्षाया एव बोधनादिति भावः । विधित्वे तु जीविकायां कर्तरि चेति निषेधे प्राप्तेऽस्यारम्भात्तद्विषये नित्यमित्येतत्सार्थकम्, क्रीडायां तु विकल्पे प्राप्तेऽस्यारम्भात्सामर्थ्यादेव नित्यत्वं सिद्धमिति बोध्यम् ॥ १७ ॥

(२७८ तत्पुरुषसंज्ञासूत्रम् ॥ २।२।१ का. १२ सू.)

४३८ कुगतिप्रादयः ॥ २।२।१८ ॥

(अनिष्टपरिहाराधिकरणम्)

(१३५६ समासप्रतिषेधवार्तिकम् ॥ १ ॥)

॥ * ॥ प्रादिप्रसङ्गे कर्मप्रवचनीयप्रतिषेधः ॥ * ॥

(भाष्यम्) प्रादिप्रसङ्गे कर्मप्रवचनीयानां प्रतिषेधो वक्तव्यः । वृक्षं प्रति विद्योतते विद्युत् । साधुर्देवदत्तो मातरं प्रति ॥

(प्रदीपः) कुगति ॥१८॥ प्रादिग्रहणस्येहागत्यर्थत्वात्कर्मप्रवचनीयानां प्रतिषेध उच्यते । प्रत्यादिविषय एवायं निषेधः तथा च त्वलोः समासो भवत्येव ॥ वृक्षं प्रतीति । वृक्षविद्युद्योतनयोः प्राप्तिक्रियाजनितस्य लक्ष्यलक्षणसंबन्धस्यावच्छेदकः प्रतिरिति सामर्थ्यसद्भावात्समासप्रसङ्गः । संबन्धाभावे तु द्वितीयापि न स्यात् ॥

(उद्योतः) कुगति ॥ १८ ॥ ननु गतिग्रहणेन प्रादीनां विशेषणात्कर्मप्रवचनीयेषु प्राप्त्यभावादनर्थकः प्रतिषेधोत आह—प्रादिग्रहणस्येति ॥ प्रत्यादिविषय एवेति । व्याख्यानादिति भावः ॥ सामर्थ्यसद्भावादिति । वृक्षगतलक्षणत्वद्योतकत्वादिति भावः ॥ द्वितीयापि न स्यादिति । कर्मप्रवचनीययुक्तत्वेयुक्तग्रहणादिति भावः ॥

(१३५७ समासप्रतिषेधवार्तिकम् ॥ २ ॥)

॥ * ॥ व्यवेतप्रतिषेधश्च ॥ * ॥

(भाष्यम्) व्यवेतानां प्रतिषेधो वक्तव्यः । आ मन्द्रैरिन्द्र हरिभिर्याहि ॥

(प्रदीपः) व्यवेतानामिति । व्यवहितानां पदान्तरेण प्रादीनां समासो न भवतीत्यर्थः ॥ आमन्द्रैरिति । याहीत्यस्यां क्रियायां द्वयोरुपनिपातात्तद्वारको दध्योदनादाविव परस्परसंबन्धोऽस्तीति समासप्रसङ्गः । तथा चैकस्वर्यं स्यादिति तत्प्रतिषेध उच्यते ॥

(उद्योतः) व्यवहितानामिति । स्वान्वययोग्यार्थवाचकप-

दापेक्षया पदान्तरेण व्यवहितानामित्यर्थः ॥ समास इति । अव्यवहितपदैरित्यर्थः ॥ सामर्थ्याभावमाशङ्क्याह—याहीति । ऐकस्वर्यमिति । अव्ययपूर्वपदप्रकृतिस्वरे सति मन्द्रस्य पृथगुदात्तत्वं न स्यादित्यर्थः ॥ यद्यपि वेदे आपाद्यं रूपं नास्ति तथापि एवंजातीयके लौकिकप्रयोगे दोष इत्यर्थः ॥ वेदेपि तस्यासाधुत्वशङ्कानिवृत्तिः फलमित्यन्ये ॥

(१३५८ उक्तवार्तिकप्रत्याख्यानवार्तिकम् ॥ ३ ॥)

॥ * ॥ सिद्धं तु काङ्स्वतिदुर्गतिवचनात् ॥ * ॥

(भाष्यम्) सिद्धमेतत् ॥ कथम् ? । 'काङ्स्वतिदुर्गतयः समस्यन्ते' इति वक्तव्यम् । कु—कुब्राह्मणः कुवृषलः । कु ॥ आङ्—आकडारः, आपिङ्गलः । आङ् ॥ सु—सुब्राह्मणः, सुवृषलः । सु ॥ अति—अतिब्राह्मणः, अतिवृषलः । अति ॥ दुर्—दुर्ब्राह्मणः, दुर्वृषलः । दुर् ॥ गति—प्रकारकः, प्रणायकः, प्रसेवकः, ऊरीकृत्य, उररीकृत्य । गति ॥

(प्रदीपः) एवं पाणिनीये लक्षणेऽतिव्याप्तिमुद्भाव्य कात्यायन आत्मीयं लक्षणं करोति—सिद्धं त्विति । तेन प्रत्यादीनां न भवति । आ मन्द्रैरित्यत्र त्वाङ्ग्रहणेन प्राप्नोतीति सामर्थ्यमेव नास्तीति वक्तव्यम् ॥

(उद्द्योतः) सामर्थ्यमेव नास्तीति । एकक्रियान्वयित्वरूपसामर्थ्यग्रहणे कृतः सर्वो वृत्तिकयेत्यादौ समासापत्तिरिति भावः । दध्योदनादौ तु क्रियान्तर्भावेण सामर्थ्यम् । एवं च वचनद्वयमपि प्रत्याख्यातमिति बोध्यम् ॥

(१३५९ समासवार्तिकम् ॥ ४ ॥)

॥ * ॥ प्रादयः क्तार्थे ॥ * ॥

(व्याख्याभाष्यम्)

प्रादयः क्तार्थे समस्यन्त इति वक्तव्यम् । प्रगत आचार्यः प्राचार्यः, प्रान्तेवासी, प्रपितामहः ॥

(प्रदीपः) प्रादयः क्तार्थे इति । अगत्यर्थमिदम् । वृत्तिविषये क्तार्थवृत्तयः प्रादयः ॥

(उद्द्योतः) वृत्तौ गतशब्दाप्रयोगे हेतुमाह—वृत्तिविषय इति । पदैकदेशन्यायेनेति भावः । प्रगतः शिष्यं प्राप्तः, गुरुं प्राप्तः, पितामहस्य पितृत्वं प्राप्त इति चार्थः ॥

(संवादभाष्यम्)

एतत्रेव च सौनागैर्विस्तरतरकेण पठितम्—

(प्रदीपः) एतदेवेति । कात्यायनाभिप्रायमेव प्रदर्शयितुं सौनागैरतिविस्तरेण पठितमित्यर्थः ॥

(१३६० सौनागवार्तिकम् ॥ १ ॥)

॥ * ॥ स्वती पूजायाम् ॥ * ॥

(व्याख्याभाष्यम्)

स्वती पूजायामिति वक्तव्यम् । सुराजा, अतिराजा ॥

(प्रदीपः) सुराजेति । न पूजनादिति समासान्तप्रतिषेधः । उपाधीनां प्रयोगविषयोपलक्षणार्थत्वादन्यत्रापि समासो भवति । तेनातिक्रमणेप्यतिः समस्यते अतिसिक्तमेव भवतेति । सुकर इत्यादौ तूपपदसमासोस्त्येव ॥

(उद्द्योतः) पूजायामित्युपलक्षणमित्याह—उपाधीनामिति ॥ अतिसिक्तमेवेति । तथाप्रयोगदर्शनादिति भावः ॥ कर्मप्रवचनीयत्वादत्र षत्वाभावः ॥

(१३६१ सौनागवार्तिकम् ॥ २ ॥)

॥ * ॥ दुर्निन्दायाम् ॥ * ॥

(व्याख्याभाष्यम्)

दुर्निन्दायामिति वक्तव्यम् । दुष्कुलम्, दुर्गवः ॥

(प्रदीपः) दुर्निन्दायामिति । प्रादिग्रहणेन यः समासस्तस्यायं विषयनिर्देश इत्यर्थान्तरेपि गतित्वात्समासो भवति—दुष्कृतमिति ॥

(उद्द्योतः) अर्थान्तरेपीत्यस्य समासो भवतीत्यनेनान्वयः । तत्र हेतुर्गतित्वादिति ॥ दुष्कृतमिति । दुः कृच्छ्रार्थे । अनभिधानात्तु भूते खल् न भवति ॥

(१३६२ सौनागवार्तिकम् ॥ ३ ॥)

॥ * ॥ आङीषदर्थे ॥ * ॥

(व्याख्याभाष्यम्)

आङीषदर्थ इति वक्तव्यम् । आकडारः, आपिङ्गलः ॥

(प्रदीपः) आङीषदर्थ इति । क्रियायोगे तु गतित्वात्समासः—आबद्धमिति ॥ आ मन्द्रैरित्यत्र तु सत्यपि सामर्थ्ये मन्द्रं प्रत्यगतित्वात्तद्वतेषदर्थाभावाच्च समासाभावः ॥

(उद्द्योतः) सत्यपीति । अपिना वस्तुतः सामर्थ्यमेव नास्तीति ध्वनितम् ॥ अगतित्वादिति । मन्द्रस्य क्रियात्वाभावादिति भावः ॥

(१३६३ सौनागवार्तिकम् ॥ ४ ॥)

॥ * ॥ कुः पापार्थे ॥ * ॥

(व्याख्याभाष्यम्)

कुः पापार्थ इति वक्तव्यम् ॥ कुब्राह्मणः, कुवृषलः ॥

(प्रदीपः) कुःपापार्थ इति । प्रशस्तेपि द्वेषान्निन्दा

भवति, पापं तु वस्तुस्थित्या गर्हितमिति निन्दापापयोर्भेदः ॥ पूर्ववदुपलक्षणार्थत्वादीषदर्थेऽपि समासो भवति—कालवणमिति ॥ अन्ये त्वाहुः—पृथिवीवाचिकुशब्दनिवृत्तये कुः पापार्थ इत्युच्यते ॥ ईषदर्थे तूत्तरपदे कादेशविधानात्समासो भवत्येव॥

(उद्द्योतः) ईषदर्थेपीति। अत एवोत्तरपदाधिकारे ईषदर्थे इति कोः कादेशविधानं चरितार्थम्। पृथ्वीवाचकस्य व्यावृत्तये त्वेतद्वचनम्। साहचर्यं तु न सर्वत्र व्यवस्थापकमिति भावः ॥

(१२६४ सौनागवार्तिकम् ॥५॥)

॥ *॥ प्रादयो गताद्यर्थे प्रथमया ॥ * ॥

(व्याख्याभाष्यम्)

प्रादयो गताद्यर्थे प्रथमया समस्यन्त इति वक्तव्यम्। प्रगत आचार्यः=प्राचार्यः प्रान्तेवासी प्रपितामहः ॥

(१२६५ सौनागवार्तिकम् ॥ ६ ॥)

॥ * ॥ अत्यादयः क्रान्ताद्यर्थे द्वितीयया ॥ * ॥

(व्याख्याभाष्यम्)

अत्यादयः क्रान्ताद्यर्थे द्वितीयया समस्यन्त इति वक्तव्यम्। अतिक्रान्तः खट्वाम्=अतिखट्वः अतिमालः ॥

(१२६६ सौनागवार्तिकम् ॥ ७ ॥)

॥*॥ अवादयः क्रुष्टाद्यर्थे तृतीयया ॥*॥

(व्याख्याभाष्यम्)

अवादयः क्रुष्टाद्यर्थे तृतीयया समस्यन्त इति वक्तव्यम्। अवक्रुष्टः कोकिलया=अवकोकिलः ॥

(१२६७ सौनागवार्तिकम् ॥ ८ ॥)

॥*॥ पर्यादयो ग्लानाद्यर्थे चतुर्थ्या ॥*॥

(व्याख्याभाष्यम्)

पर्यादयो ग्लानाद्यर्थे चतुर्थ्या समस्यन्त इति वक्तव्यम्। परिग्लानोऽध्ययनाय पर्यध्ययनः ॥

(१२६८ सौनागवार्तिकम् ॥ ९ ॥)

॥*॥ निरादयः क्रान्ताद्यर्थे पञ्चम्या ॥*॥

(व्याख्याभाष्यम्)

निरादयः क्रान्ताद्यर्थे पञ्चम्या समस्यन्त इति वक्तव्यम्। निष्क्रान्तः कौशाम्ब्याः निष्कौशाम्बिः निर्वाराणसिः ॥

(१२६९ वार्तिकम् ॥ ५ ॥)

॥ * ॥ अव्ययं प्रवृद्धादिभिः ॥ * ॥

(व्याख्याभाष्यम्)

अव्ययं प्रवृद्धादिभिः समस्यत इति वक्तव्यम्। पुनःप्रवृद्धं बर्हिर्भवति, पुनर्गवः, पुनःसुखम् ॥

(प्रदीपः) अव्ययं प्रवृद्धादिभिरिति। आदिशब्दः प्रकारे। तेन यस्याव्ययस्य समासो दृश्यते तस्यानेन समासः कार्यः ॥ सहसुपेत्यत्रोक्तमपि पुनरिह स्मरणायोक्तम्। अथ वा वार्तिकगृहीतोर्थो योगविभागेन तत्र साधित इति पौनरुक्त्याभावः ॥

(उद्द्योतः) सह' 'सुपेति योगविभागेन सिद्धे इदं व्यर्थमित्यत आह—सहसुपेत्यत्रेति ॥ एतेन नित्यार्थमिदमित्यपास्तं, तद्भाष्यप्रामाण्येनेह वार्त्तिकेषु नित्यपदासंबन्धादिति भावः ॥ वस्तुतस्तत्पुरुषसंज्ञार्थमत्र वचनानां पाठः। अत एव पुनर्गव इत्यत्र टच्। तत्र करणादतत्त्वमपि। लक्ष्यानुरोधेन व्यवस्थेत्याहुः ॥

(१२७० वार्तिकम् ॥ ६ ॥)

॥ * ॥ इवेन विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं च ॥ * ॥

(व्याख्याभाष्यम्)

इवेन सह समासो विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं च वक्तव्यम्। वाससीइव कन्येइव ॥

(१२७१ वार्तिकम् ॥ ७ ॥)

॥ * ॥ अव्ययमव्ययेन ॥ * ॥

(व्याख्याभाष्यम्)

अव्ययमव्ययेन समस्यत इति वक्तव्यम्। प्रप्रयक्षपतिम् ॥

(१२७२ वार्तिकम् ॥ ८ ॥)

॥ * ॥ उदात्तगतिमता च तिङा ॥ * ॥

(भाष्यम्) उदात्तवता तिङा गतिमता च तिङाऽव्ययं समस्यत इति वक्तव्यम्। अनुव्यचलत्, अनुव्याकरोति, यत्परियन्ति ॥ कुगति ॥ १८ ॥

(प्रदीपः) अनुव्यचलदिति। अत्र पूर्वं परत्वात्तिङ्ङतिङ इति निघातः, तत उदात्तत्वाभावाद् गतिमतेति पृथगुक्तम्। तत्र त्रयाणां पदानां समासे कृते समासान्तोदात्तत्वं भवति। तत्पुरुषे तुल्यार्थेत्यनेन तु पूर्वपदप्रकृतिस्वरत्वं न भवति। गतिर्गतावित्यनेनानोरनुदात्तत्वात्। तत्र चोदात्तस्वरितग्रहणानुवर्तनात्। विशब्दस्य तु पूर्वपदत्वाभावात् ॥ यत्परियन्तीति। उदात्तवत उदाहरणम्। निपातैर्यद्यदीति निघातप्रतिषेधाद्यन्तीत्यस्य प्रत्ययस्वरेणाद्युदात्तत्वात् परिशब्दस्य यन्तीत्यनेन समासः ॥ १८ ॥

(उद्द्योतः) अत्र पूर्वमिति। अनुना समासात्पूर्वमित्यर्थः ॥ त्रयाणां पदानामिति। गतिविशिष्टतिङन्तेनाव्ययस्य समासविधानादित्यर्थः ॥ उदात्तवतेत्यनेन तु न विना समासः निघातेन तस्योदात्तवत्त्वाभावादिति भावः ॥ तत्पुरुषे तुल्यार्थेति। समपाद इत्यादौ पूर्वपदप्रकृतिस्वरेण पूर्वपदानुदात्तत्ववारणाय उदात्तस्वरितग्रहणानुवृत्त्या तद्योगिपूर्वपदस्यैव बहुव्रीहौ प्रकृत्येत्यत्र

ग्रहणादिति भावः ॥ पूर्वपदत्वाभावादिति । विनाऽचलदित्यस्य न समासः, किं तु विविशिष्टेनाचलदित्यनेनानोरित्याद्ययः । अन्यथा वेत्यव्ययत्वे उदात्तयणः परस्मादकारस्य स्वरितत्वं स्यादिति भावः ॥ १८ ॥

(१७९ तत्पुरुषसंज्ञासूत्रम् ॥ २ । २ । १ आ. १३)

४३९ उपपदमतिङ् ॥ २।२।१९ ॥

(गतिकारकोपपदानामितिपरिभाषाधिकरणम्)

(आक्षेपभाष्यम्)

अतिङिति किमर्थम्? ॥

(प्रदीपः) उपपदम ॥ १९ ॥ **अतिङिति किमर्थमिति ।** यदि तिङन्तस्य समासो निषिध्यते तदा सुप्सुपेत्यधिकारात्तिङन्तस्य प्राप्त्यभावादनर्थकः प्रतिषेधः । अथ तिङ्शब्देन तिङर्थो लक्ष्यते तिङन्तार्थवाचिनः शब्दस्य समासनिषेधार्थं तथापि तदर्थशब्दस्तिङन्त एव भवतीत्यनर्थक एव प्रतिषेध इति प्रश्नः ॥

(उद्द्योतः) उपपदम ॥ १९ ॥ यदि तिङन्तस्येति । उपपदस्येत्यर्थः ॥ तिङन्त एवेति । कृदभिहितस्य द्रव्यवद्भावादिति भावः ॥ न च मा भवान्भूदित्येतद्व्यावृत्तयेऽतिङन्तः समासः इत्यर्थकं तत्, माङीत्यस्य सतीत्यर्थात् तत्रोपपदत्वमेव नेत्यदोषात् । प्रथमार्थे सौत्री सप्तमी हि उपपदसंज्ञालिङ्गम् । अतएव षष्ठाविस्यादौ नोपपदत्वम् । तुमुन्ण्वुलावित्यत्र तु क्रियार्थोपपदस्येति क्रियार्थमुपपदत्वमावश्यकमिति भाष्याशयः ॥

(समाधानभाष्यम्)

कारको व्रजति, हारको व्रजति ॥

(प्रत्याख्यानभाष्यम्)

अतिङिति शक्यमवक्तुम् ॥

(आक्षेपभाष्यम्)

कस्मान्न भवति—कारको व्रजति, हारको व्रजति? ॥

(समाधानभाष्यम्)

सुप्सुपेति वर्तते ॥

(समाधानवार्तिकावतरणभाष्यम्)

अत उत्तरं पठति—

(प्रदीपः) अत इति । यस्मात् तिङन्तस्यानर्थकः प्रतिषेध इत्यर्थः ॥

(१३७३ समाधानवार्तिकम् ॥ १ ॥)

॥ * ॥ उपपदमतिङिति तदर्थप्रतिषेधः ॥ * ॥

(व्याख्याभाष्यम्)

उपपदमतिङिति तदर्थस्यायं प्रतिषेधः ॥ कस्य? ॥ तिङर्थस्य ॥ कः पुनस्तिङर्थः? । क्रिया ॥

(प्रदीपः) तच्छब्देनार्थशब्दसन्निधाने तिङर्थ उच्यते । स तिङन्तस्यार्थोऽर्थो यस्य स **तदर्थः ॥ कस्येति ।** सामान्याभिधानाद् विशेषावधारणाय प्रश्नः ॥ **कः पुनरिति ।** कालसाधनसंख्यापुरुषक्रियोपग्रहरूपस्तिङर्थः । तदर्थश्च तिङन्त एव संभवति नान्यत्रेति प्रश्नः ॥ **क्रियेति ।** अनेकार्थसंभवेपि साध्यत्वात् क्रिया प्रधानम् । प्रधानं चार्थस्तिङ्ग्रहणेन वचनसामर्थ्याल्लक्ष्यते ॥

(उद्द्योतः) अर्थशब्दसन्निधाने इति । तिङन्तशब्दरूपार्थकस्योपपदस्याभावादिति भावः ॥ तिङर्थ उच्यतइति । कस्य ? तिङर्थस्येति भाष्येपि तिङ्पदेन तदर्थो ग्राह्य इति भावः ॥ कस्येति प्रश्नोपि तदर्थशब्दार्थप्रश्नद्वारा तच्छब्दार्थप्रश्न एवेति बोध्यम् ॥ पुरुषः प्रत्यक्त्वादिः, उपग्रहः कर्त्रभिप्रायत्वादिः ॥ यद्यपि कर्त्रभिप्रायत्वं न तिङर्थस्तथापि यथाकथंचित् बोध्यं भवत्येवेति बोध्यम् ॥ तिङर्थ इत्यस्य तिङन्तार्थ इत्यर्थः ॥ अनेकार्थेति । कालसाधनादिरूपेत्यर्थः ॥ साध्यत्वादिति । साधनसाध्यत्वेन शाब्दप्राधान्यादित्यर्थः ॥

(१३७४ व्यासान्तरवार्तिकम् ॥ २ ॥)

॥ * ॥ क्रियाप्रतिषेधो वा ॥ * ॥

(व्याख्याभाष्यम्)

अथ वा व्यक्तमेवेदं पठितव्यम्—उपपदमक्रियेति ॥

(प्रदीपः) **क्रियाप्रतिषेधो वेति ।** यदि तिङ्ग्रहणेन वचनसामर्थ्यात् क्रिया लक्षणीया तदा प्रतिपत्तिलाघवाय साक्षात् क्रियाप्रतिषेधः कर्तव्य इत्यर्थः ॥

(उद्द्योतः) तिङ्ग्रहणमपनीय क्रियापदग्रहणे लाघवं दर्शयति—यदीति ॥

(आक्षेपभाष्यम्)

अथ—अक्रियेति किं प्रत्युदाह्रियते? ॥

(प्रदीपः) अत्रापि पक्षे सुबन्तस्य क्रियावाचित्वाभावान्निर्विषय एव प्रतिषेध इत्याह—**अथेति ॥**

(प्रत्युदाहरणभाष्यम्)

कारको गतः, कारको यातः ॥

(प्रदीपः) **कारको गत इति ।** गतशब्दः क्रियावाच्युपपदं तत्र **तुमुन्ण्वुलाविति** ण्वुल् । कर्तुं गत इत्यर्थः ॥ अत्रातिङ्ग्रहणात् समासाभावोऽन्यथा गतकारक इति स्यात् । अत्र च प्रकृतिवाच्यक्रियाश्रयो ण्वुल् । तदाश्रयं गतशब्दस्य क्रियावाचित्वमिति समासप्रतिषेधः ॥

(उद्द्योतः) अतिङ्ग्रहणादिति । अक्रियाग्रहणादित्यपि बोध्यम् ॥ नन्वत्र गतशब्दस्य सत्त्वप्रधानतया कथं क्रियावाचित्वमित्याशङ्क्याह—अत्रचेति । द्रव्यवाचित्वे प्रत्ययानुपपत्तिः क्रियावाचित्वे तु उपपदसमासो दुर्वार इति तद्व्यावृत्त्यर्थमक्रियाग्रहणमिति भावः ॥

(बाधकभाष्यम्)

नैतत्क्रियावाचि ॥ किं तर्हि ? । द्रव्यवाचि ॥

(प्रदीपः) **नैतदिति** । सुबन्तविशेषणमतिङ्ग्रहणम् । न चात्र सुबन्तं क्रियावाचि । प्रकृत्यर्थस्य ह्यत्र गुणीभावः । प्रत्ययार्थस्य कर्तुः प्राधान्यम् तस्य च द्रव्यरूपेण कृताभिधानम् । प्रधानेन च व्यपदेशो भवतीति द्रव्यवाचीत्युक्तम् । अत एव गतशब्दस्य समासो न प्राप्नोति तस्यानुपपदत्वाद् । धातोश्च क्रियावाचित्वात् तदाश्रया प्रत्ययोत्पत्तिरविरुद्धा । धात्वर्थस्य प्रत्ययार्थेन संसृष्टत्वात् पदान्तरेणैकार्थीभावासंभवात् समासस्य त्वप्रसङ्गः धातोः सुबन्तत्वाभावाच्च ॥

(उद्द्योतः) इदानीमेव क्रियावाचित्वोपपादनादाह—**सुबन्तेति** । उपपदविशेषणमित्यर्थः ॥ **नैतत् क्रियावाचीति** भाष्यस्य नैतत्प्राधान्येन क्रियावाचीत्यर्थः ॥ नन्वेवमत्र समासो दुर्वारोत आह—**अत एवेति** ॥ प्रत्ययोत्पत्तिनिमित्तमुपपदत्वं च न गतशब्दस्य किं तु धातोरेवेत्याह—**धातोश्चेति** । अन्वर्थाभावेपि सामर्थ्यादुपपदत्वमित्यभिमानः ॥ ननु प्रत्ययोत्पत्तिवत्समासोपि स्यादत आह—**धात्वर्थस्येति** । एवं च तन्मात्रस्यान्येनैकार्थीभावासम्भव इति भावः ॥ वस्तुतस्तु **नैतत् क्रियावाची**त्यनेनात्र तुमुन्ण्वुलाविति ण्वुलेव नेति बोध्यते । **क्रियार्थायामिति** स्त्रीलिङ्गनिर्देशेन क्रियार्थायाः क्रियाया एव लाभे पुनः क्रियाग्रहणेन प्राधान्येन साध्यमात्रावस्थक्रियाप्रतिपादकस्यैव ग्रहणात् । किं च क्रियाशब्देन क्रियावाचकशब्दग्रहणे क्रिया प्रधानभूता साध्यावस्थैवात्र गृह्यते इति **गतिकारकोपपदादिति** सूत्रेपि भाष्ये स्फुटम् ॥ अर्थग्रहणे तु गुणीभूताया अपि ग्रहणमिति पाकादियोगे कारकविभक्तिकृत्वसुजादीनां साधुत्वं भवत्येवेत्याशयः ॥ अन्यथा सिद्धान्ते कारको गत इत्यत्र समासो दुर्वारः स्यात् ॥ किं च क्रियावाचित्वाभावादत्राप्रत्युदाहरणत्वम् । तुमुलन्तं तु भवतीत्यस्यान्याय्यत्वात् ॥ कैयटोक्तरीतिस्त्वनुपसर्जनाद् **'येनविधिः' समर्थः पदे**त्यादिसूत्रभाष्यविरुद्धा । तत्र हि निष्कृष्यैकार्थीभावं विनापि समासतद्धितादिप्रवृत्तेरङ्गीकारात् । न चैवमपि कारको व्रजतितरामित्यत्र समासाभावार्थं प्रतिषेध आवश्यकः, अनभिधानेन तत्र तादृशप्रयोगाभावादिति भाष्याशयः ॥

(प्रत्युदाहरणान्तरभाष्यम्)

इदं तर्हि—कारकस्य गतिः कारकस्य व्रज्येति ॥

(प्रदीपः) **कारकस्य गतिरिति** । गमनं गतिरिति भावे प्रत्ययविधानात् क्रियावाचित्वमस्तीति भावः ॥

(बाधकभाष्यम्)

एतदपि द्रव्यवाचि । कथम् ? । कृदभिहितो भावो द्रव्यवद्भवतीति ॥

(प्रदीपः) **एतदपीति** । धातुरत्र साध्यभूतां क्रियां प्रत्याययति । प्रत्ययस्तु तस्या एव क्रियाया उपसंहृतक्रमरूपां सत्त्वरूपतामाह । प्रत्ययार्थश्च प्रधानमिति यत्सुबन्तं न तत्क्रियावाचि यत्क्रियावाचि, न तत्सुबन्तमित्यर्थः ॥ **द्रव्यवदिति** । यथा घटादेर्द्रव्यस्य लिङ्गसंख्यासाधनसंबन्धः तथा कृदभिहितस्यापि भावस्येत्यर्थः ॥

(उद्द्योतः) उपसंहृतक्रमरूपां, उपसंहृतक्रमत्वसमानाधिकरणवैजात्यविशेषरूपाम् ॥ **प्रधानमितीति** । प्रत्ययार्थवैजात्येन लिङ्गाधनन्वयरूपप्रकृत्यर्थवैजात्यकार्याभिभवात्तस्य प्राधान्यमिति भावः ॥ एवं चात्रापि न ण्वुलिति तात्पर्यं भाष्यस्येति बोध्यम् ॥

(सिद्धान्तसमाधानभाष्यम्)

एवं तर्हि सिद्धे सति यद् 'अतिङ्' इति प्रतिषेधं शास्ति तज्ज्ञापयत्याचार्यः—अनयोर्योगयोर्निवृत्तं सुप्सुपेति ॥ किमेतस्य ज्ञापने प्रयोजनम् ? । 'गतिकारकोपपदानां कृद्भिः सह समासो भवति' इत्येषा परिभाषा न कर्तव्या भवति ॥

(प्रदीपः) **अनयोरिति** ॥ नन्वत्रैव सूत्रे अतिङ्ग्रहणात् सुपो निवृत्तिर्ज्ञाप्यतां पूर्वत्र कथं ज्ञाप्यते । एवं तर्हि योगविभागः क्रियते—तेन **'अतिङ्'** इति सूत्रद्वयशेषो ज्ञायत इत्यदोषः । अतिङ्ग्रहणेन च समासो योगद्वयविहितो विशेष्यते—अतिङन्तः समासो भवतीति । तेन **सुपे**त्यस्यैव निवृत्तिर्ज्ञाप्यते । सुब्ग्रहणं तु पूर्वस्य पदस्य पदकार्यार्थमनुवर्तत एव । भाष्येपि समुदायस्य निवृत्तिर्विवक्षिता, न तु केवलस्य सुबित्यस्य ॥ **गतिकारकोपपदानामिति** । एतत्सूत्रद्वये सुपेत्यस्य निवृत्त्या गतीनामुपपदानां च उत्तरपदात् सुबुत्पत्तेः प्राक्समाससिद्धिः । कारकाणां तु **कर्तृकरणे कृता बहुलमिति** समासः क्रियते । तत्र कृद्ग्रहणात् प्राक्सुबुत्पत्तेः समासः । तिङन्तेन तृतीयान्तस्य सुपेत्यस्यानुवर्तनात् समासाप्रसङ्गात् कृदन्तेनैव समासे सिद्धे कृद्ग्रहणं कृदन्तावस्थायामेवानुत्पन्ने सुपि समासार्थम् । अस्याश्च परिभाषायाः **पुंयोगादाख्यायामि**त्यत्र प्रयोजनानि वक्ष्यन्ते । यदि तर्ह्युत्तरपदात्सुब्नोत्पद्यते तदा दधिसेचाविस्यादौ पदादित्वाभावात्षत्वप्रतिषेधो न प्राप्नोति । पदत्वाभावादुत्तरपदव्यपदेशश्च न ततश्च तन्निबन्धनस्वरो न सिध्यति ॥ नैष दोषः । निरुपपदात्सिचयतेः क्विपि कृते षष्ठीसमासः क्रियत इति षत्वनिषेधो भविष्यति । यद्वा सुपेत्यस्य निवृत्तौ सत्यां यथेष्टं कार्यसिद्धये क्वचिदुत्पन्ने सुपि समासः क्वचित्प्राक्सुबुत्पत्तेः । एवं कारकसमासोपि बहुलग्रहणात् क्वचित्सुबुत्पत्तेर्भवतीति **स्वा हि तस्य धनक्रीतेति** प्रयोग उपपन्नः । उत्तरपदशब्दे समासावयवविशेषस्य रूढिरिति तत्राप्यदोषः ॥

(उद्द्योतः) भाष्ये—**एवंतर्हि सिद्धे इति** । तादृशप्रयोगाभावादतिप्रसङ्गनिरासे सिद्ध इत्यर्थः ॥ **एवं तर्हि योगविभाग इति** । अत्र 'अतिङिति, पूर्वसूत्रे 'गतिः' इति चेत्यर्थः ॥ **अतिङ्ग्रहणेन चेति** । अतिङित्यस्य प्रथमान्ततया समास एव विशेष्यते । अवि-

ङिति वहुव्रीहिः। प्रपचतितरामित्यादौ नित्यसमास इष्ट एव। **तिङि-चोदात्तवती**त्यनेन गतेर्निघातेन्तोदात्तत्वमेव। तत्र एतस्मिन्नर्थमेव तिङ्ग्रहणं प्रत्याख्यातं भाष्ये **गतिकारके**ति स्वरस्य तु नात्र प्रवृत्तिः कृद्ग्रहणात्। कृद्ग्रहणप्रत्याख्यानं तु न भाष्यारूढमिति तत्रैव वक्ष्यामः॥ एतेन तत्र नित्यसमासवारणायातिङिति तद्घटितप्रतिषेधायावश्यकमिति कथं तत्र तन्निवृत्तिज्ञापकम्।प्रपचतितरामित्यादौ च **गतिकारकोपपदा**दिति **तिङिचोदात्तवती**ति सूत्रभाष्यप्रामाण्येनोदात्तवतेत्यादिवार्तिकोक्तो वैकल्पिकसमास एवेष्यते इति परास्तम्॥ **सुब्ग्रहणं स्विति**। **उपपद**मित्यन्वर्थसंज्ञया सुबन्तस्यैव पदत्वेनोपपदत्वात् गतेः सुबन्तत्वाच्च राजयुध्वेत्यादौ पूर्वपदे नलोपादिपदकार्यसिद्धेः। तिङन्ताघटित इति समासविशेषणेन कारको व्रजतीत्यादिव्यावृत्तिसिद्धेः प्रथमान्तसुबनुवृत्तेरपि फलाभावेन चिन्त्यमेतत्॥ **कृदन्तावस्थायामेवेति**। काष्ठः पचतितरामित्यादिवारणाय कृद्ग्रहणस्यावश्यकत्वेन चिन्त्यमिदमिति कश्चित्। तन्न, बहुलग्रहणेन शानजन्तादिभिरिव तेनापि समासस्य वारयितुं शक्यत्वात्॥ परिभाषायाः प्रयोजनवत्त्वे ह्यतिङ्ग्रहणं प्रयोजनवत्स्यादत आह—**अस्याश्चेति॥ तन्निबन्धनः स्वर इति। गतिकारकोपपदात् कृदिति** विहित इत्यर्थः॥ स्वरासिद्ध्यरुचेराह—**यद्वेति॥ सुपेत्यस्य निवृत्ताविति।** सुपेवेति नियमाभावाद्यथेष्टं समाससिद्धिरितिभावः। लक्ष्यानुसारेण च व्यवस्थेति बोध्यम्। तत्र **सुबुत्पत्तेः प्रागि**त्युपलक्षणं लिङ्गबोधकप्रत्ययोत्पत्तेः प्रागपीति बोध्यम्॥ **सुबुत्पत्तेरिति**। सुबुत्पत्तेरनन्तरमित्यर्थः॥ **धनक्रीतेति**। सुप्त्रयुत्पत्तेः पूर्वं समासे **क्रीतात्करणे**तिङीप् स्यात्। सुबन्तेन तु समासेन्तरङ्गत्वाट्टाप् सिध्यतीति भावः॥ यत्र सुबुत्पत्तेः पूर्वं समासस्तत्र स्वराप्राप्तेराह—**उत्तरपदशब्द इति**॥

(आक्षेपभाष्यम्)

यद्येतज्ज्ञाप्यते केनेदानीं समासो भविष्यति?॥

(प्रदीपः) **यद्येतदिति**। शब्देनोत्तरपदस्यानुपादानात् प्रश्नः॥

(समाधानभाष्यम्)

समर्थेन॥

(प्रदीपः) **समर्थेनेति**। सुबित्यस्यानुवृत्तौ सत्यां समासस्य पदविधित्वात्समर्थपरिभाषोपस्थानात्॥

(उद्द्योतः) **सुबित्यस्येति**। तदननुवृत्तावपि प्रागुक्तरीत्या पदविधित्वं बोध्यम्॥

(आक्षेपभाष्यम्)

यद्येवं धातूपसर्गयोरपि समासः प्राप्नोति पूर्वं धातुरुपसर्गेण युज्यते पश्चात्साधनेनेति॥

(प्रदीपः) **यद्येवमिति**। ततश्चैकस्वर्यादिप्रसङ्गः शाकलप्रतिषेधप्रसङ्गश्च॥ **पूर्वं धातुरुपसर्गेणेति**। ततस्तयोः सामर्थ्यमस्ति। उपसर्गार्थविशिष्टायाः क्रियायाः साधनयोगात्॥

(उद्द्योतः) सुपेत्यस्याननुवृत्तावतिप्रसङ्गमाह—भाष्ये—**यद्येवमिति**। कुगतीत्यनेनेति भावः। अतिङित्यनेन तिङन्तस्यैव प्रतिषेध इति तात्पर्यम्॥ **ऐकस्वर्यादीति**। आदिनैकपद्यम्। किं च तयोः समासे प्रातिपदिकतया परत्वात्सुबुत्पत्तिरेव स्यान्न तिङित्यपि बोध्यम्॥ **पूर्वं धातुरुपसर्गेणेति**। तत्संज्ञकशब्देनेत्यर्थः॥

(समाधानभाष्यम्)

नैतदस्ति। पूर्वं धातुः साधनेन युज्यते पश्चादुपसर्गेण। साधनं हि क्रियां निर्वर्तयति। तामुपसर्गो विशिनष्टि। अभिनिर्वृत्तस्य चार्थस्योपसर्गेण विशेषः शक्यो वक्तुम्॥

(प्रदीपः) **पूर्वं धातुः साधनेनेति**। ततश्च पूर्वं साधनाभिधायिप्रत्ययोत्पत्तिः पश्चात्साधनसंसृष्ट एव धातुरुपसर्गेण युज्यते न केवल इति धातूपसर्गयोः समासाभावः तत्र कृदन्तेन समासो भवत्येव तिङन्तेन त्वतिङिति निषेधान्न भवति। यत्र तु तिङन्तेन समास इष्यते स विषयो दर्शितः—**उदात्तवतेति॥ अभिनिर्वृत्तस्येति**। अनिष्पन्नस्य विशेषाकाङ्क्षाया अभावादनुभूयते सुखमुपास्यते गुरुरित्यादौ धातुरेव सकर्मिकां क्रियां वक्ति, उपसर्गस्तु द्योतक इति नास्ति कश्चिदस्मिन् पक्षे दोषः॥

(उद्द्योतः) पूर्वं साधनेन योगेपि उपसर्गस्य क्रियाविशेषकत्वाविशेषात्सामर्थ्यस्य दुर्वारत्वमित्यत आह—**ततश्च पूर्वमिति**। साधनसंसृष्ट एवोपसर्गेण युज्यत इति केवलेन सामर्थ्याभाव इति भावः॥ न च निष्कृष्यैकार्थीभावो न समासादिप्रयोजक इत्युक्तम्, एवं च विशिष्टेनैकार्थीभावेऽवयवानामपि तत्सत्त्वात्स दुर्वार इति वाच्यम्। तिङन्तेनैकार्थीभावाभावात् अतिङिति निषेधात् तदवयवेन तु प्रत्ययासंसृष्टेन नैकार्थीभावः साधनसंसृष्टार्थस्यैवोपसर्गेण योगादित्यदोषात्॥ भाष्ये—**साधनं हि क्रियां निर्वर्त्तयतीति**। **क्रियां** तत्प्रतीतिं, साध्यत्वेन प्रतीतेः तत्संबन्धाधीनत्वात् साध्यत्वेन प्रतीतार्थकयोगे च तेषामुपसर्गत्वादिति भावः॥ **अभिनिर्वृत्तस्य**। अभिनिर्वृत्तज्ञानविषयस्येत्यर्थः॥ **अनिष्पन्नस्येति**। अज्ञातस्येत्यर्थः॥ नन्वेवमुपसर्गसम्बन्धात् प्राक्केवलभ्वासादेः सकर्मकत्वाभावेन कर्मणि लादयो न स्युरत आह—**अनुभूयते सुखमिति॥ धातुरेवेति**। केवलधातुरेवेत्यर्थः॥ **उपसर्गस्तु द्योतक इति**। स च श्रोतृबोधाय पश्चादेव सम्बध्यते इति भावः॥ एतेनोपसर्गाणां द्योतकत्वेपि तद्द्योत्यार्थस्य साधनसम्बन्धात् पूर्वमेव धातुना बोधनावश्यकत्वेन धातूपसर्गयोः सामर्थ्यसत्त्वेन समासो दुर्वार इत्यपास्तम्॥ एतच्च **सुट्‍ा**दित्यत्र विस्तरेणोपपादयिष्यते॥ **विपराभ्यां** जेरित्यादौ व्यादिद्योत्यार्थप्रतिपादकस्येत्यर्थः विपराभ्यां परत्वयोग्यस्येत्यर्थो वा॥

(उपपदसमासबलीयस्त्वाधिकरणम्)

(१३७५ विप्रतिषेधवार्तिकम्॥ ३॥)

॥ * ॥ षष्ठीसमासादुपपदसमासो विप्रतिषेधेन॥ * ॥

(भाष्यम्) **षष्ठीसमासादुपपदसमासो भवति**

विप्रतिषेधेन। षष्ठीसमासस्यावकाशः—राज्ञः पुरुषो राजपुरुषः। उपपदसमासस्यावकाशः—स्तम्बेरमः कर्णेजपः। इहोभयं प्राप्नोति—कुम्भकारो नगरकारः। उपपदसमासो भवति विप्रतिषेधेन॥

(प्रदीपः) **षष्ठीसमासादिति**। नित्यत्वानित्यत्वाभ्यामनयोर्विरोधसद्भावः॥ **कुम्भकारइति**। पक्षके प्रातिपदिकार्थे प्रातिपदिकेनैव कर्मण उक्तत्वात् तत्रैवोपपदेऽणा भाव्यम्। अपवादविषयत्वाद् द्वितीयानुत्पादात् कृते चाणि **कर्तृकर्मणोरि**ति षष्ठी भवतीत्यस्त्युभयप्रसङ्गः॥

(उद्द्योतः) **विरोधसद्भावइति**। इत्यभिमान इति शेषः॥ अभिमानत्वं चास्यानुपदमेव स्फुटीकरिष्यते॥ ननु कर्मण्युपपदेऽण् कर्मत्वं च विभक्त्या गम्यं तत्राणुत्पत्तेः पूर्वं कृदन्तत्वाभावात्षष्ठ्या अप्राप्तौ द्वितीययैव भाव्यमिति जातेपि अणि तन्निवृत्तौ मानाभाव इति कुतः षष्ठीसमासप्राप्तिरत आह—**पक्षके इति**। प्रातिपदिकस्य पदत्वाभावादुपपदत्वं कथमिति चिन्त्यमेतत्॥ **सुबन्तमेवोपपदमिति**। तत्रोपपदमितिसूत्रे भगवान्वक्ष्यति स्वयं च। किं च पक्षकपक्षेपि सकलकारकशक्तिमानर्थः संमुग्धाकारेणैव प्रातिपदिकेनोच्यते न तु विशिष्य इतिकर्मोपपदत्वप्रयुक्ताणोप्राप्तिः। अन्यथा करणाद्युपपदेपि कर्मोपपदप्रसङ्गः, तस्माद्वस्तुतः कृत्प्रकृत्यर्थकर्मत्वसत्त्वेन कृदनुत्पत्तावपि भावितत्वं गृहीत्वा षष्ठीप्रवृत्तिरित्येव भाष्याशय उचितः॥

(१३७६ विप्रतिषेधप्रत्याख्यानवार्तिकम्॥ ४॥)

॥ * ॥ न वा षष्ठीसमासाभावादुपपदसमासः॥ * ॥

(भाष्यम्) **न वार्थो विप्रतिषेधेन। किं कारणम्?। षष्ठीसमासस्याभावादुपपदसमासो भविष्यति 'गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक्सुबुत्पत्तेः' इति समासवचनात्॥**

(प्रदीपः) **गतिकारकेति**। यतश्चोत्तरपदे विभक्त्युत्पत्त्यनपेक्षणादन्तरङ्गत्वादुपपदसमासो भवतीत्यर्थः॥

(उद्द्योतः) **अन्तरङ्गत्वादिति**। षष्ठीति सूत्रे सुपेति तृतीयान्तस्य संबन्धाविति भावः। अत एव मातुः स्मरतीत्यादौ न षष्ठीसमासः। अत एव च षष्ठ्यन्तस्यानेकसुबन्तेन न समास इति बोध्यम्॥

(उक्तवार्तिकद्वयवैयर्थ्यभाष्यम्)

अथ वा विभाषा षष्ठीसमासः। यदा न षष्ठीसमासस्तदोपपदसमासो भविष्यति॥

(प्रदीपः) **अथ वेति**। षष्ठीसमासेपि दोषाभाव इत्यर्थः॥

(उद्द्योतः) एतद्वार्तिकद्वयमपि प्रत्याचष्टे—**अथ वेति** भाष्ये। **विप्रतिषेधे** परमित्यस्य तु न प्रवृत्तिः, युगपदुभयविहितत्पुरुषसमाससंज्ञयोः प्रवृत्तिसंभवेनासंभवरूपविप्रतिषेधाभावात्॥ उपपदसमासो भविष्यतीत्यस्योपपदमिति सूत्रविहितसमाससंज्ञा तत्पुरुषसंज्ञा च स्यात्सतीत्यर्थः। अन्यादृशविरोधस्य तत्प्रवृत्तिनिमित्तत्वे न मानमिति तात्पर्यम्। न च नित्यत्वानित्यत्वज्ञानयोर्विरोधः, बोधे बाधज्ञानस्याप्रतिबन्धकत्वात्। एवं च षष्ठीसमासोपि नित्य एवैतद्विषये फलितः तद्बोधिताभावांशस्यैतद्विरोधेनैतद्विषये त्यागात् नित्यं क्रीडेत्यादिविषये तस्य कृत्सबाधत्वाद्॥ **गतिकारकोपपदा**दित्यत्र प्रकृतपरिभाषायां च लक्षणप्रतिपदोक्तपरिभाषा न प्रवर्तते इति षष्ठीसमासोपि सुबुत्पत्तेः पूर्वमेव। स्वरश्च तत्रापि समासे इत्यन्तरङ्गत्वमेव नास्तीति भावः। परिभाषायां सामान्यतः कारकपदोपादानेन कारकविभक्त्यन्तसमासमात्रस्य सुबुत्पत्तेः प्राक् कृद्भिर्लाभात् इति बोध्यम्॥

(वैयर्थ्यबाधकभाष्यम्)

अनेनैव यथा स्यात्। तेन मा भूदिति॥ कश्चात्र विशेषः—तेन वा स्यादनेन वा?। अयमस्ति विशेषः—उपपदसमासो नित्यसमासः, षष्ठीसमासः पुनर्विभाषा॥

(प्रदीपः) क्वचित् कार्ये दोषदर्शनादाह—**अनेनेति**। [**ञ्नित्यसमासयो**रित्यत्र नित्यसमासग्रहणेनास्य ग्रहणं यथा स्याद्] **अन्तोदात्तादुत्तरपदा**दित्यत्रानित्यसमासग्रहणेनास्य ग्रहणं मा भूदिति भावः॥

(उद्द्योतः) कैयटे **ञ्नित्यसमासयो**रित्यादिर्यथास्यादित्यन्तोऽग्रन्थः बहुषु पुस्तकेष्वनुपलम्भात्तत्र नित्यग्रहणप्रत्याख्यानाच्च॥ **उत्तरपदेति**। एवं चाग्निचितेत्यादौ विभक्त्युदात्तत्वमपि स्यादिति भावः॥ १९॥

(नित्यसमासलक्षणाधिकरणम्)

(वैयर्थ्यसाधकाक्षेपभाष्यम्)

ननु च नित्यं यः समासः स नित्यसमासः यस्य विग्रहो नास्ति॥

(प्रदीपः) **यस्य विग्रहो नास्तीति**। अस्यापि विग्रहाभावः। षष्ठीसमासेन मुक्ते पक्षे उपपदसमाससद्भावात्॥

(वैयर्थ्यबाधकभाष्यम्)

नेत्याह। नित्याधिकारे यः समासः स नित्यसमासः॥

(प्रदीपः) **नित्याधिकार इति**। नित्यशब्दस्य स्वरितत्वप्रतिज्ञानात् तदधिकारसंप्रत्ययः॥

(वैयर्थ्यसाधकभाष्यम्)

नैवं शक्यम्। अव्ययीभावस्य ह्यनित्यसमासता प्रसज्येत। तस्मान्नित्यः समासो नित्यसमासः यस्य विग्रहो नास्ति॥ उपपद॥ १९॥

(प्रदीपः) **नैवं शक्यमिति**। नित्यशब्दस्य स्वरितत्वं दोषवत्त्वान्न प्रतिज्ञायते इत्यर्थः। तदेवं प्रयोजनाभावाद्विप्रतिषेधो न पठितव्यः॥ १९॥

(२८० तत्पुरुषसंज्ञानियमसूत्रम् ॥ २ । २ । १ आ. १४)

४४० अमैवाव्ययेन ॥ २।२।२० ॥

(अनिष्टपरिहाराधिकरणम्)

(आक्षेपभाष्यम्)

एवकारः किमर्थः ? ॥

(समाधानभाष्यम्)

नियमार्थः ॥

(समाधानबाधकभाष्यम्)

नैतदस्ति प्रयोजनम् । सिद्धे विधिरारभ्यमाणोऽन्तरेणैवकारं नियमार्थो भविष्यति ॥

(समाधानसाधकभाष्यम्)

इष्टतोवधारणार्थस्तर्हि भविष्यति । यथैवं विज्ञायेत—अमैवाव्ययेनेति ॥ मैवं विज्ञायि—अमाव्ययेनैवेति ॥

(आक्षेपभाष्यम्)

अस्ति चेदानीं कश्चिदनव्ययममूशब्दो यदर्थो विधिः स्यात् ॥

(प्रदीपः) **अमैवा ॥ २० ॥ यदर्थ इति ।** यन्निवृत्त्यर्थोयं नियमः स्यादित्यर्थः ॥

(समाधानभाष्यम्)

अस्तीत्याह—खशयं ब्राह्मणकुलमिति ॥

(प्रदीपः) **खशयमिति । अधिकरणे शेतेरित्यच् ।** अतोमिति सोरम्भावः । अनेनानव्ययेनामा समासो मा भूद् इत्येवमर्थोयं नियमः स्यात् ॥

(समाधानबाधकभाष्यम्)

नैतदस्ति प्रयोजनम् । अन्तरङ्गत्वादत्र समासो भविष्यति ॥

(प्रदीपः) **अन्तरङ्गत्वादिति ।** अनुत्पन्न एव सावुपपदसमासेन भाव्यं पश्चात् सुपेति समासविधानकाले अनव्ययस्यामोसंभवान्नियमान्तरे वचनस्य चरितार्थत्वाद्विपरीतनियमो न भविष्यतीत्यर्थः ॥

(उद्द्योतः) **अमैवा ॥ २० ॥** नन्वेवं वचनवैयर्थ्यमतस्तत्सामर्थ्यात्सुवुत्पत्त्यनन्तरमपि समासो ज्ञाप्यते इत्यत आह—**नियमान्तरे इति ।** वक्ष्यमाणे इत्यर्थः ॥

(समाधानसाधकभाष्यम्)

इदं तर्हि प्रयोजनम् । अमैव यत्तुल्यविधानमुपपदं तत्र यथा स्याद् अमा चान्येन च यत्तुल्यविधानं तत्र माभूदिति । अग्रे भोजम् । अग्रे भुक्त्वा ॥

(प्रदीपः) **अमैवेति ।** एवकारसामर्थ्यादमेत्यस्यावृत्तिराश्रीयते । ततो येन वाक्येनामेव केवलो विधीयते न प्रत्यान्तरसहितस्तेन वाक्येन यद्विधीयते उपपदं तत्र सप्तमीनिर्देशात् तदमा समस्यते नान्यदित्यर्थः ॥ **अग्रे भोजमिति ।** विभाषाग्रेप्रथमपूर्वेष्विति द्वयोः क्त्वाणमुलोर्विधानादत्र समासो न भवति ॥

(उद्द्योतः) **अमेत्यस्यावृत्तिरिति ।** चिन्त्यमेतत् । आवृत्तौ मानाभावात् अमैव तुल्यविधानं यदुपपदं तदमाव्ययेन समस्यते इत्यर्थे अग्रेभुक्त्वा इत्यत्र समासापत्तिरव्ययग्रहणवैयर्थ्यापत्तिश्च । किं च कालो भोक्तुमित्यत्र समासापत्तिः । तस्मादमैव तुल्यविधानं यदुपपदं तदव्ययेनेति नियमेन सर्वेष्टसिद्धिः । अत एव भाष्येऽग्रे भुक्त्वेत्यप्युदाहृतम् *अग्रादिष्वप्राप्तेति वार्त्तिकप्रत्याख्यानं च संगच्छते इत्याहुः ॥

(नियमफलभाष्यम्)

अग्रादिष्वप्राप्तविधेः समासप्रतिषेधं चोदयिष्यति । स न वक्तव्यो भवति ॥ अमैवा० ॥ २० ॥

(प्रदीपः) **अग्रादिष्विति ।** यतोऽप्राप्तविभाषा ततः प्रत्ययोत्पत्तावग्रादीनां निमित्तत्वान्निमित्तस्योपपदत्वात् समासप्रसङ्गः । प्राप्तविभाषायां त्वग्रादीनां प्रत्ययोत्पत्तावनिमित्तत्वात्तन्निवृत्तावेव हेतुत्वात् तस्यानुपपदत्वमित्यर्थः ॥ २० ॥

(उद्द्योतः) **अप्राप्तविधेरिति** विशेषणव्यावर्त्यमुपपादयति—**प्राप्तविभाषायां त्विति ।** आभीक्ष्ण्य इत्यनुवृत्त्या हि सा, तस्मिंश्च सत्येव प्रत्यय इत्याद्युक्तेः प्रत्ययोत्पत्तिसंनियोगेनैवोपपदसंज्ञास्वीकारादिति भावः ॥ २० ॥

(इति तत्पुरुषप्रकरणम्)

—>o<—

(अथ बहुव्रीहिप्रकरणम्)

(२८१ बहुव्रीहिसंज्ञासूत्रम् ॥ २ । २ । १ आ. १५ सू.)

४४३ शेषो बहुव्रीहिः ॥ २।२।२३ ॥

(शेषपदार्थनिर्वचनाधिकरणम्)

(आक्षेपभाष्यम्)

शेष इत्युच्यते कः शेषो नाम ? ॥

(प्रदीपः) **शेषो ॥ २३ ॥** पदस्यार्थस्य च सर्वस्योपयुक्तत्वाच्छेषमसंभाव्य पृच्छति—**शेष इति ॥**

(उद्द्योतः) **शेषो ॥ २३ ॥** उपयुक्तादन्यः शेषः ॥

(एकदेशिसमाधानभाष्यम्)

येषां पदानामनुक्तः समासः स शेषः ॥

(१३७७ समाधानबाधकवार्तिकम् ॥ १॥)

॥ * ॥ शेषवचनं पदतश्चेन्नाभावात् ॥* ॥

(भाष्यम्) **शेषवचनं पदतश्चेत् । तन्न । किं कारणम् ? । अभावात् । नहि सन्ति तानि पदानि येषां पदानामनुक्तः समासः ॥**

(प्रदीपः) **पदतश्चेदिति ।** पदेन पदत इत्याद्यादित्वात्

तसिः ॥ नह्यीति । सर्वेषां सामान्यविशेषरूपेणोपयुक्तत्वादित्यर्थः ॥

(उद्योतः) सामान्यम्—सह सुपेत्यादिः । विशेषः—द्वितीयाश्रितेत्यादिः ॥

(एकदेशिसमाधानान्तरभाष्यम्)

अर्थतस्तर्हि शेषग्रहणम्—येष्वर्थेषु अनुक्तः समासः स शेषः ॥

(१३७८ समाधानान्तरबाधकवार्तिकम् ॥ २ ॥)

॥ * ॥ अर्थतश्चेदविशिष्टम् ॥ * ॥

(भाष्यम्) **अर्थतश्चेदविशिष्टमेतद्भवति । कुतः? । पदतः । नहि सन्त्यर्थाः येष्वर्थेष्वनुक्तः समासः ॥**

(प्रदीपः) **नहि सन्त्यर्था इति** । पूर्वोत्तरान्यपदार्थेषु तत्पुरुषाव्ययीभावविधानात् ॥

(उद्योतः) **पूर्वोत्तरेति** । यद्यप्यन्यपदार्थवत् पूर्वोत्तरपदार्थयोस्तद्विधानं नासच्छास्त्रे तथाप्यव्ययीभावादिमहासंज्ञाबलेन पूर्वाचार्यपरिगृहीतार्थस्य निमित्तत्वमस्त्येवेत्यभिप्रायः ॥

(सिद्धान्तिसमाधानभाष्यम्)

त्रिकतस्तर्हि शेषग्रहणम् । यस्य त्रिकस्यानुक्तः समासः स शेषः ॥ कस्य चानुक्तः ? । प्रथमायाः ॥ शेषो ब० ॥ २३ ॥

इति श्रीभगवत्पतञ्जलिविरचिते व्याकरणमहाभाष्ये द्वितीयस्याध्यायस्य द्वितीये पादे प्रथममाह्निकम् ॥

(प्रदीपः) **प्रथमाया इति** । द्वितीयादीनां प्रतिपदं समासविधानात् प्रथमायाः शेषत्वम् । ततश्च प्रथमान्तानां पदानां बहुव्रीहिरित्यर्थात् समानाधिकरणानां भवति । कण्ठेकाल इत्यादौ **सप्तमीविशेषणे** इति पूर्वनिपातविधानात् ज्ञापकाद्भवति ॥ २३ ॥

इत्युपाध्यायजैयटपुत्रकैयटकृते भाष्यप्रदीपे द्वितीयस्याध्यायस्य द्वितीये पादे प्रथममाह्निकम् ॥

(उद्योतः) **विशेषणं विशेष्येणेत्यादौ** प्रथमाया अप्युपयुक्तत्वमित्यत आह—**द्वितीयादीनामिति । गतार्थे प्रथमयेत्यादि** तु व्याख्यानभूतम्, न स्वतन्त्रविधायकमिति भावः ॥ यद्वा **शेष** इत्यस्य प्रथमान्तत्वात्प्रथमान्तगृहीतत्रिकस्य प्रतिपदमुच्चरितस्यैव ग्रहणमिति सर्वेष्टसिद्धिः ॥ २३ ॥

इति शिवभट्टसुतसतीगर्भजनागोजीभट्टकृते भाष्यप्रदीपोद्योते द्वितीयाध्यायस्य द्वितीयपादे प्रथममाह्निकम् ॥

द्वितीयाध्यायस्य द्वितीयपादे द्वितीयमाह्निकम् ॥

(२८२ बहुव्रीहिसंज्ञासूत्रम् ॥ २ । २ । २ आ. १ सू.)

४४४ अनेकमन्यपदार्थे ॥ २।२।२४ ॥

(पदकृत्याधिकरणम्)

(आक्षेपभाष्यम्)

पदग्रहणं किमर्थम्? ॥

(प्रदीपः) **अनेक** ॥ २४ ॥ अनेकग्रहणस्य वार्तिककारः प्रयोजनं वक्ष्यतीति भाष्यकारः पदग्रहणस्यान्यग्रहणस्य च प्रयोजनमाचष्टे ॥ बहुवक्तव्यत्वाच्च पश्चादन्यग्रहणस्य विचारः ॥ **पदग्रहणमिति** । अन्यार्थे इत्युच्यमाने स्वपदार्थव्यतिरिक्ते अर्थान्तर आश्रीयमाणे अन्यपदार्थो लभ्यते । वर्तिपदानां च क्रियालक्षणे वाक्यार्थे वृत्त्यसंभवात्तन्निवृत्त्यर्थमपि पदग्रहणं नोपयुज्यत इति प्रश्नः ॥

(उद्योतः) **अनेकम** ॥ २४ ॥ भाष्ये क्रमोल्लङ्घनेभिप्रायमाह—**अनेकेति** ॥ **अन्यपदार्थो लभ्यते इति** । अन्यार्थे इत्यस्य भिन्नेर्थे इत्यर्थः ॥ भेदप्रतियोगी चोपस्थितः स्वपदार्थ एव । पर्युदासविधया च स पदार्थ एवेति भावः ॥ वाक्यव्यावर्तकं युक्त्यन्तरमाह—**वर्तीति** ॥ तेषां सुबन्तत्वादित्यभिमानः ॥

(समाधानभाष्यम्)

इह "अनेकमन्यार्थे" इतीयत्युच्यमाने वाक्यार्थेपि बहुव्रीहिः स्यात्—यथा मे माता तथा पिता सुस्नातं भो इति । पदग्रहणे पुनः क्रियमाणे न दोषो भवति ॥

(प्रदीपः) **यथा मे मातेति** । कश्चित् केनचित् पृष्टः कीदृशः कुलशीलादिना तव पितेति स आह—यथा मे मातेति । एतानि पदानि तथा मे पितेत्यन्यस्य वाक्यस्यार्थं गमयन्तीति समासप्रसङ्गः । अथ वा स्नाहीति कश्चित् केनचिदुक्तः तं प्रत्याह—यथा मे मातेत्यादि यथा शुद्धकुला मे माता तथा पितापीत्यभिजनशुद्धिरपि स्नानं किं वाद्येन स्नानेनेत्यर्थः । ततः सुस्नातं भो इत्येतद्वाक्यार्थे वर्तमानानां यथाप्रभृतीनां पदानां समासाभावार्थं पदग्रहणम् । अश्रुतवाक्यार्थे च पदानां वृत्तिर्दृश्यते यथा नद्यां शिष्णासुः कश्चिदुच्यते—नद्यां ग्राहाः सन्तीति । तस्माच्च मा स्नासीरिति वाक्यार्थः प्रतीयते ॥

(उद्योतः) **एतानि पदानीति** । समानाधिकरणानामित्यनपेक्ष्येदम् । वस्तुतोर्थपरमेतत् यथा मदीया मातेत्यत्र समासप्रसङ्ग इति बोध्यम् ॥ **सुस्नातं भो** इतिपाठे आह—**अथ वेति** । अत्र सर्वत्रान्यार्थो व्यङ्ग्य इति बोध्यम् । अभिजनशुद्धिरपीत्यपिरेवार्थे । भाष्ये वाक्यशब्देन पदसमूहमात्रम् ॥

(आक्षेपभाष्यम्)

अथान्यग्रहणं किमर्थम्? ॥

(प्रदीपः) अथान्यग्रहणमिति । अन्तरङ्गत्वात् स्वपदार्थे समासे सिद्धे पदार्थग्रहणसामर्थ्यादन्यपदार्थो लप्स्यत इति प्रश्नः ॥

(समाधानभाष्यम्)

"अनेकं पदार्थे" इतीयत्युच्यमाने स्वपदार्थेपि बहुव्रीहिः स्यात्—राजपुरुषः तक्षपुरुष इति ॥

(प्रदीपः) स्वपदार्थेपीति । अपिशब्दादन्यपदार्थेपीत्यर्थः । पदार्थग्रहणं व्याप्तिसमाश्रयणार्थं स्यादिति स्वपदार्थान्यपदार्थयोः समासः स्यात् ॥

(उद्द्योतः) व्याप्तिसमाश्रयणेति । पदार्थग्रहणसामर्थ्याद् व्याप्तिन्यायस्यैवानुसरणम्, नान्तरङ्गन्यायस्येत्यर्थः । राजानं पुरुषमित्यर्थे सावकाशस्तत्पुरुषः, बहुव्रीहिरपि बहुपदे सावकाश इति प्रथमान्तपदद्वयेन विग्रहे परत्वात्स्वपदार्थेपि बहुव्रीहिः प्राप्नोतीति तद्व्यावृत्त्यर्थमन्यग्रहणम्, त्रिकतश्चात्र शेष इति भावः ॥

(एकदेशिसमाधानबाधकभाष्यम्)

नैतदस्ति प्रयोजनम् । तत्पुरुषः स्वपदार्थे बाधको भविष्यति ॥

(प्रदीपः) तत्पुरुष इति । बहुव्रीहेस्त्वन्यपदार्थोऽवकाशः ॥

(उद्द्योतः) भाष्ये एकदेश्याह—नैतदस्तीत्यादि । तत्पुरुषः, समानाधिकरणतत्पुरुषः राजपुरुष इत्यादिरपि कर्मधारय एव ॥

(एकदेशिन आक्षेपभाष्यम्)

भवेदेकसंज्ञाधिकारे सिद्धम् । परंकार्यत्वे तु न सिध्यति । आरम्भसामर्थ्यात्तत्पुरुषः, परंकार्यत्वाच्च बहुव्रीहिः प्राप्नोति ॥

(प्रदीपः) परंकार्यत्वाच्चेति । ततश्च संज्ञयोः समावेशात् स्वरसमासान्तप्रसङ्गः ॥

(उद्द्योतः) इतर एकदेश्याह—भवेदित्यादि ॥ स्वरसमासान्तेति ॥ पर्यायेणेत्यर्थः । यद्वा कस्यचित्स्वरः कस्यचित्समासान्त इत्यर्थः ॥

(समाधानभाष्यम्)

परंकार्यत्वे च न दोषः । शेष इति वर्तते । अशेषत्वान्न भविष्यति ॥

(उद्द्योतः) भाष्ये—अशेषत्वान्न भविष्यतीति । पदतोऽर्थतो वा शेष इत्यभिमानः ॥

(शेषग्रहणप्रत्याख्यानभाष्यम्)

शेषवचनं उक्तम् । किमुक्तम् ? । *तत्र शेषवचनाद्दोषः संख्यासमानाधिकरणनञ्समासेषु बहुव्रीहिप्रतिषेधः* इति ॥

(प्रदीपः) शेषवचन इति । शेषग्रहणप्रत्याख्यानं स्मारयति—संख्येति । द्वीरावतीको वीरपुरुषकोऽब्राह्मणको देश इति समासविध्युपयोगादशेषत्वाद् बहुव्रीहिर्न प्राप्नोति । तस्माच्छेषग्रहणं न कर्तव्यम् । ततः स्वपदार्थे बहुव्रीहिनिवृत्त्यर्थमन्यग्रहणं कर्तव्यमिति स्थितम् ॥

(उद्द्योतः) एतदर्थकं शेषग्रहणं प्रत्याख्यातमित्याह—प्रत्याख्यानमिति । आकडारसूत्रोक्तमित्यर्थः । पदतोऽर्थतश्च शेषे द्वीरावतीके दोषः, पदत एव शेषे वीरपुरुषकादौ दोषः ॥ समासविधाविति । संख्यावंश्येन, नदीभिश्च, अन्यपदार्थे च संज्ञायाम्, मध्यमध्यमवीराश्च, नञित्येति भावः । पदतोऽर्थतश्च शेषार्थकस्य तस्य प्रत्याख्याने परंकार्यमिति पाठेऽन्यग्रहणमावश्यकमित्याह—तत इति ॥

(आक्षेपभाष्यम्)

अथैकसंज्ञाधिकारे नार्थोऽन्यग्रहणेन ? ॥

(समाधानभाष्यम्)

एकसंज्ञाधिकारे च कर्तव्यम् । अक्रियमाणे ह्यन्यग्रहणे यथैव तत्पुरुषः स्वपदार्थे बहुव्रीहिं बाधते एवमन्यपदार्थेपि बाधेत ॥

(प्रदीपः) अक्रियमाण इति । नीलोत्पलं सर इत्यत्रापि विशेषानुपादानादन्यपदार्थेऽपि स्वपदार्थ इव तत्पुरुषो बहुव्रीहिं बाधेत, कण्ठेकाल इत्यादिश्च व्यधिकरणपदो बहुव्रीहेरवकाशः स्यात् । अन्यग्रहणे तु सति स्वपदार्थे सावकाशं तत्पुरुषं परत्वाद्बहुव्रीहिर्बाधत इति न कश्चिद्दोषः ॥

(उद्द्योतः) नीलोत्पलं सर इति । इदमुपलक्षणं बहुपदकबहुव्रीहिः स्वपदार्थेपि स्यादित्यपि बोध्यम् । परिनिष्ठितविभक्त्य समासमजानतो भाष्ये—अक्रियमाणे इत्याद्युक्तिरिति बोध्यम् ॥ कण्ठेकाल इत्यादिश्चेति । बहुपदके बहुव्रीहिविधानं सावकाशमिति वक्तुं युक्तम् ॥

(आक्षेपभाष्यम्)

अथानेकग्रहणं किमर्थम् ? ॥

(प्रदीपः) अथेति । एकनिवृत्त्यर्थं तावदनेकग्रहणं नोपपद्यते । पदविधित्वात् सामर्थ्ये सति बहुव्रीहिसंज्ञाविधानादनेकाधिष्ठानत्वाच्च सामर्थ्यस्य । नापि बहूनां समासार्थमनेकग्रहणं तद्धितार्थेत्यनेन उत्तरपदे परतः समाससंज्ञाविधानाज्ज्ञापकाद्बहूनां बहुव्रीहेः सिद्धत्वादिति प्रश्नः ॥

(आक्षेपबाधकभाष्यम्)

"अन्यपदार्थे" इतीयत्युच्यमाने एकस्यापि पदस्य बहुव्रीहिः स्यात्—सर्पिषोपि स्यात्, गोमूत्रस्यापि स्यात् ॥

(प्रदीपः) सर्पिषोऽपि स्यादिति । अपिशब्दो बिन्द्वर्थे वर्तते इति तस्यापि बहुव्रीहिसंज्ञाप्रसङ्गः । ततश्च कप्समासान्तप्रसङ्गः । पदान्तरेण स्यादित्यनेन चास्य सामर्थ्यमस्तीति समर्थपरिभाषापि न व्यावृत्तिं करोतीत्येवं केचिद्व्याचक्षते ॥ अन्ये त्वाहुः—अपिः पदार्थेत्यत्राप्यर्थता बिन्द्वादेर्निराकृता। तस्मात्स्यादिति पदं बिन्द्वर्थे वर्तत इति तस्य बहुव्रीहिसंज्ञाप्र-

सञ्ज्ञः ॥ अतिङ्ग्रहणेन च पूर्वमेव सुप्सुपेत्यस्य विच्छिन्नत्वादेकस्यापि तिङन्तस्य प्राप्तिः स्यात् ॥

(उद्द्योतः) ततश्चेति । न चैकसंज्ञाधिकारात् बहुव्रीहिसंज्ञया कर्मप्रवचनीयत्वबाधे पत्वं स्यात् । किं च कर्मप्रवचनीयत्वस्य निरवकाशत्वेन तया बाधाद्बहुव्रीहिसंज्ञैव न भविष्यतीति वाच्यम् । उपसर्गसंज्ञाया अपि तद्रीत्या बाधात् । परंकार्यत्वपक्षे समावेशसंभवाच्चेत्यभिमानः ॥ केचिदिति । अत्रारुचिस्तु स्यादित्यनेन व्यपेक्षासत्त्वेप्येकार्थीभावाभावः ॥ स्यादिति पदमिति । प्रकृतिप्रत्ययार्थयोरत्रैकार्थीभावः स्यादित्यभिमानः । अत्र व्याख्याने एकसंज्ञाधिकारेप्युक्तदोषो न संज्ञयोर्भिन्नाश्रयत्वात् ॥ विच्छिन्नत्वादिति । अतिङ्ग्रहणं तु नानुवर्तते व्याख्यानादिति भावः ॥

(आक्षेपसाधकभाष्यम्)

नैतदस्ति प्रयोजनम् । सुप्सुपेति वर्तते ॥

(प्रदीपः) नैतदिति । योगद्वय एवातिङ्ग्रहणेन सुप्सुपेत्यस्यासंबन्धो ज्ञापितोऽन्यत्र सुप्सुपेत्यनुवर्तत एवेत्यर्थः ॥

(उद्द्योतः) योगद्वये एवेति । तत्रैवातिङ्पदसंबन्धादिति भावः ॥

(आक्षेपबाधकभाष्यम्)

इदं तर्हि प्रयोजनम् । बहूनामपि यथा स्यात्—सुसूक्ष्मजटकेशेन सुनताजिनवाससा ॥

(प्रदीपः) बहूनामपीति । अन्यथा सुप्सुपेति गुणे संख्याया विवक्षितत्वाद् द्वयोरेव स्यात् ॥

(उद्द्योतः) गुणे संख्याया इति । सुबन्तत्वस्य प्रत्येकसमाप्तत्वादिति तु वक्तुं युक्तम् ॥

(आक्षेपबाधकशेषभाष्यम्)

उत्तरार्थं चानेकग्रहणं कर्तव्यम्—"चार्थे द्वन्द्वः" अनेकमिति । इहापि यथा स्यात्—प्लक्षन्यग्रोधधवखदिरपलाशा इति ॥

(आक्षेपसाधकनिराकरणभाष्यम्)

एतदपि नास्ति प्रयोजनम् । आचार्यप्रवृत्तिर्ज्ञापयति 'बहूनामपि समासो भवति' । यदयम्—उत्तरपदे द्विगुं शास्ति ॥

(प्रदीपः) उत्तरपदइति । द्विगुग्रहणं तद्धितार्थेत्यनेन विहितस्य समासस्योपलक्षणम् । तेन दिशः समानाधिकरणेनोत्तरपदे समासावयवविशेषे परतः समासविधानं बहूनां समासस्य ज्ञापकमित्यर्थः । द्विगुस्तु ब्रह्मजातादौ सावकाशत्वान्न ज्ञापकः ॥

(उद्द्योतः) समासविधानं चेति पाठे चस्त्वर्थे ॥ ब्रह्मजातादाविति । कालाः परिमाणिनेति सूत्रस्थेनोत्तरपदेन परिमाणिना द्विगोः सिद्धय इति वार्त्तिकेन सिद्धे बहूनां तत्पुरुषे इत्यर्थः । तदपि वचनमेतज्ज्ञापकसिद्धमेव नापूर्वमित्याशयेन भाष्ये द्विगुग्रहणम् ॥

(प्रत्याक्षेपभाष्यम्)

तत्पुरुषोपि तर्हि बहूनां प्राप्नोति ॥

(प्रदीपः) तत्पुरुषोपीति । ज्ञापकफलस्य विषयविभागाभावादनिष्टप्रसङ्गो महत्कष्टं श्रित इत्यत्रापि तत्पुरुषप्रसङ्गात् ॥

(उद्द्योतः) तत्पुरुषोपीत्यस्य कालाः परिमाणिनेत्येतद्भिन्नोपि तत्पुरुष इत्यर्थ इत्यन्ये ॥ ज्ञापकफलस्येति । संख्याऽविवक्षारूपस्येत्यर्थः । यद्वा यथाकथंचित्सुबन्तत्वादिग्रहणरूपस्येत्यर्थः ॥

(प्रत्याक्षेपबाधकभाष्यम्)

नैष दोषः । ग्रहणेन तत्पुरुष उच्यते तेन बहूनां न भविष्यति ॥

(प्रदीपः) ग्रहणेनेति । विशिष्टपूर्वोत्तरपदनिर्देशेनेत्यर्थः । तत्र द्वितीयान्तस्य श्रितादिभिः समासविधानात्प्रत्ययग्रहणपरिभाषोपस्थानात् समुदायस्याद्वितीयान्तत्वादत्र तत्पुरुषाभावः ॥ यद्येवमिहापि सुप्सुपेत्यनुवर्तनात्कथं बहूनां बहुव्रीहिः । अथ ज्ञापकेन संख्याविवक्षा बाध्यते तदा द्वितीयादिष्वपि संख्याया अविवक्षा स्यात् ॥ नैष दोषः, तत्पुरुषविधौ सुप्सुपेति संख्या प्रतीयते द्वितीयेत्यपि । द्वन्द्वबहुव्रीह्योस्तु सुप्सुपेत्यत्रैव संख्याप्रतीतिः । तत्र ज्ञापकेनैकैव संख्याप्रतीतिर्बाध्यते । तावता चरितार्थत्वाद् द्वितीयादिषु संख्याया अबाधः ॥

(उद्द्योतः) सर्वस्यापि समासस्य ग्रहणेन विधानादाह—विशिष्टेति । संख्याविवक्षेति । मुख्यसुबन्तत्वपर्याप्त्यधिकरणग्रहणविवक्षेत्यपि बोध्यम् ॥ संख्याया अविवक्षेति । यथा कथंचिद् द्वितीयान्तग्रहणविवक्षेत्यपि बोध्यम् ॥ अबाध इति । अन्यत्र मुख्यद्वितीयाद्यन्तग्रहणम्, सुप्सुपेत्यत्र तु ज्ञापकेन यथाकथंचित्सुबन्तग्रहणमिति तत्त्वम् । अत्र तदपि द्वन्द्वबहुव्रीहिविधायके एवेष्टानुरोधात् परिमाण्युत्तरपदकसमासविधौ चेति बोध्यम् । ग्रहणेन तत्पुरुष इत्यत्र तत्पुरुषपदमव्ययीभावस्याप्युपलक्षणम् ॥

(समाधानभाष्यम्)

अत उत्तरं पठति—

(१३७९ समाधानवार्तिकम् ॥ १ ॥)

॥ * ॥ अनेकवचनमुपसर्जनार्थम् ॥ * ॥

(व्याख्याभाष्यम्)

अनेकग्रहणं क्रियते उपसर्जनार्थम् । "प्रथमानिर्दिष्टं समास उपसर्जनम्" इत्युपसर्जनसंज्ञा यथा स्यात्—चित्रगुः शबलगुरिति ॥

(प्रदीपः) चित्रगुरिति । सत्यनेकग्रहणे सुबित्येवानुवर्तते न तु सुपेति । तन्निवृत्त्यर्थत्वात्तस्य । ततश्चोत्तरपदमपि तेन प्रत्याय्यत इति समासशास्त्रे गोशब्दस्य प्रथमानिर्दिष्टत्वादुपसर्जनत्वाद्ध्रस्वसिद्धिः ॥

(उद्द्योतः) तन्निवृत्त्यर्थत्वादिति । इदं चिन्त्यम् । तदनुवृत्तावपि द्वयोः समासाभावार्थं तदित्यस्यापि वक्तुं शक्यत्वात् तन्नि-

वृत्तिं विना सर्वेषामुपसर्जनत्वासंभवो द्वयोः समासालाभश्चेति व्याख्यानात्तन्निवृत्तिरिति तत्त्वम् ॥

(१३८० समाधानबाधकवार्तिकम् ॥ २ ॥)

॥ * ॥ न वैकविभक्तित्वात् ॥ * ॥

(व्याख्याभाष्यम्)

न वा एतदपि प्रयोजनमस्ति । किं कारणम् ? । एकविभक्तित्वात् "एकविभक्ति चापूर्वनिपाते" इत्युपसर्जनसंज्ञा भविष्यति चित्रगुः शबलगुरिति । चित्रा यस्य गावश्चित्रगुस्तिष्ठति । चित्रा यस्य गावश्चित्रगुं पश्येति । चित्रा यस्य गावश्चित्रगुणा कृतम् । चित्रा यस्य गावश्चित्रगवे देहि । चित्रा यस्य गावश्चित्रगोरानय । चित्रा यस्य गावश्चित्रगोः स्वम् । चित्रा यस्य गावश्चित्रगौ निधेहि । चित्रा यस्य गावो हे चित्रगो इति ॥

(प्रदीपः) न वेति । अन्यपदार्थस्य प्राधान्याद्दर्शनाद्यनेकक्रियायोगादनेकविभक्तित्वेऽपि वर्तिपदानामेकविभक्तित्वादित्यर्थः ॥

(उद्द्योतः) वर्त्तिपदानामेकविभक्तित्वादिति । समासापेक्षयेति शेषः ॥

(आक्षेपभाष्यम्)

यदि तर्हि कुतश्चिदेव किंचित्पदमध्याहृत्य एकविभक्तियोगः क्रियते, एतदप्येकविभक्तियुक्तम्, इहापि प्राप्नोति—राजकुमारी तक्षकुमारी । राज्ञो या कुमारी राजकुमारी तिष्ठति । राज्ञो या कुमारी राजकुमारीं पश्य । राज्ञो या कुमारी राजकुमार्या कृतम् । राज्ञो या कुमारी राजकुमार्यै देहि । राज्ञो या कुमारी राजकुमार्या आनय । राज्ञो या कुमारी राजकुमार्याः स्वम् । राज्ञो या कुमारी राजकुमार्यां निधेहि । राज्ञो या कुमारी राजकुमारि इति ॥

(प्रदीपः) यदि तर्हीति । अयं भावः—चित्रा गावोऽस्येत्यस्मिन्विग्रहवाक्ये न कस्यचिदनेकविभक्तित्वं यदपेक्षया वर्तिप्रदानामेकविभक्तित्वं स्यात् । अथ यथाकथंचिद् अन्यस्यानेकविभक्तित्वमाश्रित्य वर्तिपदस्यैकविभक्तित्वं व्यवस्थाप्यते । तदातिप्रसङ्गो राज्ञो या कुमारी तां पश्य, तया कृतं, तस्यै देहीत्याश्रयेण कुमारीशब्दस्यैकविभक्तित्वादुपसर्जनह्रस्वत्वं स्यात् ॥

(उद्द्योतः) यदपेक्षयेति । विग्रहे यदेकविभक्तिकमित्युक्तौ प्रत्यासत्त्या विग्रहीयपदान्तरापेक्षया यत्तादृशमिति लभ्यते । नहि चित्रा गाव इत्येतत्तथेति भावः ॥ अथेति । यथाकथंचित्पर्यायेण अन्यस्य समासस्य समासपदाघटितकिंचिदेकविभक्तिकमित्यर्थ इति भावः । भाष्ये कुतश्चिदेव समासार्थविग्रहे इत्युक्तिरूपहेतोः किंचित्पदं समासरूपमध्याहृत्येत्यस्य ज्ञानविषयीकृत्येत्यर्थः । तदपेक्ष इति च शेषः ॥ अनेनोक्तेप्यर्थे प्रत्यासत्तिमूलकत्वं दर्शितम् । अत एव सभार्य इत्यदावुपसर्जनत्वेन ह्रस्वसिद्धिः । अन्यथा विग्रहीयसहपदे विभक्तेरेवाभावेन तदपेक्षया नियतविभक्तित्वाभावात्तदप्राप्तिः । मम तु अनियतविभक्तिकसमासान्तत्वं सूपपादं लुका विभक्त्यनुत्पत्तेरेवान्वाख्यानाच्च । राज्ञो या कुमारीति प्रथमान्तेनैव समास इति दूषणम् ॥

(समाधानभाष्यम्)

एकविभक्तियुक्तमेव यन्नित्यम् । न चैतन्नित्यमेकविभक्तियुक्तमेव राज्ञः कुमारीं पश्य राजकुमारीं पश्येत्यपि भवति ॥ किं वक्तव्यमेतत् ? । नहि ॥ कथमनुच्यमानं गंस्यते ? । एकग्रहणसामर्थ्यात् । यदि हि यदेकविभक्तियुक्तं चानेकविभक्तियुक्तं च तत्र स्याद्, एकग्रहणमनर्थकं स्यात् । "विभक्तियुक्तमपूर्वनिपाते" इत्येव ब्रूयात् ॥

(प्रदीपः) एकविभक्तियुक्तमेवेति । अयं भावः—नायं नियमः प्रथमान्तस्यैव कुमारीशब्दस्य षष्ठीसमासेन भाव्यम् । किं तर्हि ? द्वितीयाद्यन्तस्यापि । ततश्च समासे विधीयमाने एकविभक्तित्वाभावात् कुमारीशब्दस्योपसर्जनत्वाभावः ॥ एकग्रहणसामर्थ्यादिति । एकैकस्मिन्प्रयोगे सर्वस्यैव एकविभक्तित्वादेकविभक्तिग्रहणं पर्यायेणानेकविभक्तेर्निरासार्थमित्यर्थः ॥ विभक्तियुक्तमिति । एतदपि किमर्थमुच्यत इति चेत्संज्ञिनिर्देशार्थम् । अन्यथा अपूर्वनिपात इत्येतावदुच्यमाने संज्ञ्यनिर्दिष्टः स्यात् ॥

(उद्द्योतः) किं तर्हीति । वाक्यसंस्कारे परिनिष्ठितविभक्त्यापि समास इति समाधानम् ॥ ततश्चेति । तस्य चेत्यर्थः ॥ पर्यायेणेति । प्रयोगभेदेनापि यत्रैकविभक्तित्वमेव तत्र यथा स्यादित्यर्थमिति भावः । तदेवं प्रत्यासत्त्यनाश्रयणेन समासापेक्षया विग्रहे यन्नियतविभक्तिकमित्यर्थमाश्रित्यानेकग्रहणं भगवता प्रत्याख्यातम् । ज्ञापकक्लेशं परिहर्तुमनेकग्रहणं सूत्रकृता कृतमिति दिक् ॥

(अनुप्रयोगानुपपत्तिपरिहाराधिकरणम्)

(१३८१ आक्षेपवार्तिकम् ॥ ३ ॥)

॥ * ॥ पदार्थाभिधानेऽनुप्रयोगानुपपत्तिरभिहितत्वात् ॥ * ॥

(भाष्यम्) पदार्थाभिधाने ऽनुप्रयोगस्यानुपपत्तिः—चित्रगुर्देवदत्त इति ॥ किं कारणम् ? । अभिहितत्वात् । चित्रगुशब्देनाभिहितः सोऽर्थ इति कृत्वानुप्रयोगो न प्राप्नोति ॥

(प्रदीपः) पदार्थाभिधान इति । देवदत्तपदस्य यावानर्थस्तावान् बहुव्रीहिणा वक्तव्योऽन्यपदार्थे तस्य विधानात् ततो गतार्थत्वादनुप्रयोगो न प्राप्नोतीत्यर्थः । यथा चार्थे

द्वन्द्वविधानाद् द्वन्द्वे चशब्दस्य प्रयोगो न भवति । एवमिहापि देवदत्तादिपदानां न स्यात् ॥

(१३८२ आक्षेपबाधकवार्तिकम् ॥ ४ ॥)

॥ * ॥ न वानभिहितत्वात् सामान्याभिधाने हि विशेषानभिधानम् ॥ * ॥

(व्याख्याभाष्यम्)

न वा एष दोषः । किं कारणम् ? । अनभिहितत्वात् । चित्रगुशब्देनानभिहितः सोर्थ इति कृत्वाऽनुप्रयोगो भविष्यति ॥ कथमनभिहितः, यदिदानीमेवोक्तम् *पदार्थाभिधानेऽनुप्रयोगानुपपत्तिरभिहितत्वाद्* इति ? । सामान्याभिधाने हि विशेषानभिधानम् । सामान्ये ह्यभिधीयमाने विशेषोनभिहितो भवति । तत्रावश्यं विशेषार्थिना विशेषोनुप्रयोक्तव्यः । चित्रगुः कः ? । देवदत्त इति ॥

(प्रदीपः) सामान्याभिधाने हीति । चित्रगुशब्देन तद्वन्मात्रमुच्यते न तु विशेषः ॥

(आक्षेपभाष्यम्)

भवेत्सिद्धं यदा सामान्ये वृत्तिः । यदा तु खलु विशेषे वृत्तिः, तदा न सिध्यति—चित्रा गावो देवदत्तस्येति चित्रगुर्देवदत्त इति ॥

(प्रदीपः) यदा सामान्य इति । चित्रा गावोस्येत्येवं विग्रहे कृतेऽन्यपदार्थसामान्यस्य बहुव्रीहिणाभिधानाद्विशेषस्यानुप्रयोगो भवतु यदा विशिष्टेऽन्यपदार्थे बहुव्रीहिः क्रियते तदानुप्रयोगासिद्धिः ॥

(समाधानभाष्यम्)

तदापि सिद्धम् । कथम् ? । नेदमुभयं युगपत्संभवति । वाक्यं समासश्च । यदा वाक्यम्, न तदा समासः । यदा समासः, न तदा वाक्यम् । यदा समासः, सामान्येन तदा वृत्तिः । तत्रावश्यं विशेषार्थिना विशेषोनुप्रयोक्तव्यः—चित्रगुः कः ?, देवदत्त इति ॥

(प्रदीपः) नेदमुभयमिति । लौकिके प्रयोगे वृत्तिवाक्ययोर्युगपत् प्रयोगाभावात् एकेनैवार्थस्य प्रत्यायितत्वादितरप्रयोगायोगात् ॥ यदा समास इति । शब्दशक्तिस्वाभाव्यादन्यपदार्थसामान्यमेवाभिधातुं समर्थः समासो न विशेषमिति प्रक्रियायामपि सामान्येन विग्रहः कार्य इत्यर्थः ॥

(उद्द्योतः) वाक्यमुपमृद्य समासप्रवृत्तेस्तस्यापि बुध्यारूढत्वमस्तीत्यत आह—लौकिके प्रयोगे इति । लोके सर्वेषां चित्रगुपदशक्यत्वेन तस्य सामान्यशब्दत्वमिति सामान्येनैव विग्रहः कार्य इति विशेषवाक्यं न युक्तिस्थमिति यदा समासः, सामान्येन तदा वृत्तिरिति भाष्यार्थ इति भावः ॥

(आक्षेपभाष्यम्)

सामान्यस्यैव तर्ह्यनुप्रयोगो न प्राप्नोति—चित्रगुः कः ? । चित्रगु तत्, चित्रगु किंचित्, चित्रगु सर्वमिति ॥

(प्रदीपः) सामान्यस्यैव तर्हीति । सामान्यस्य समासेनैवाभिधानात् ॥

(समाधानभाष्यम्)

सामान्यमपि यथा विशेषस्तद्वत् । तत्र चित्रग्वित्युक्ते संदेहः स्यात्—सर्वं वाऽविभ्रं वेति । तत्रावश्यं विशेषार्थिना विशेषोनुप्रयोक्तव्यः—चित्रगु तदिति ॥

(प्रदीपः) सामान्यमपीति । यथा विशेषो विशेषान्तरस्य निवर्तकस्तद्वत्सामान्यमपि विशेषाणां निवर्तकं सद्विशेष एवेत्यर्थः ॥ चित्रग्विति । लिङ्गसर्वनाम्ना नपुंसकेन निर्देशः सामान्यवृत्तिनामेव प्रकाशयितुं कृतः ॥ सर्वं वाविभ्रं वेत्यत्राकारप्रश्लेषः कृतः । अन्यथा पर्यायप्रयोगः स्यात् ॥ तत्रावश्यमिति । चित्रगु सर्वमित्युक्ते न ह्येकमेवेति विशेषावगतिर्भवतीत्यर्थः ॥

(उद्द्योतः) सद्विशेष एवेति । इतरभेदकत्वमेव विशेषत्वमिति भावः ॥ अविभ्रमित्यस्यासर्वमित्यर्थः ॥

(समाधानान्तरभाष्यम्)

अथवा विभक्त्यर्थोभिधीयते । एतच्चात्र युक्तं यद्विभक्त्यर्थोभिधीयते तत्र हि सर्वपश्चात्पदं वर्तते अस्येति ॥

(प्रदीपः) अथ वेति । कृत्स्नपदार्थाभिधानेऽनुप्रयोगासिद्धिश्चोदिता परिहृता च । यदा तु विभक्त्यर्थः संबन्धादिरभिधीयते समासेन तदा तद्वाचिनी विभक्तिर्नानुप्रयोक्ष्यते द्रव्यं त्वनभिहितमिति तद्वाची शब्दोऽवश्यमनुप्रयोक्तव्यः । कथं पुनरन्यपदार्थ इत्युच्यमाने विभक्त्यर्थ एव गृह्यत इत्यत आह—तत्र हीति । पदेन प्रकृत्यर्थोपसर्जनः प्रत्ययार्थोभिधीयत इति विभक्त्यर्थस्यैव प्राधान्यादन्यपदार्थग्रहणेन ग्रहणमित्यर्थः ॥ सर्वपश्चादिति । भाष्यकारवचनप्रामाण्यादव्ययेनापि षष्ठीसमासः ॥

(उद्द्योतः) चित्रा गावो देवदत्तस्येति विग्रहेपि न देवदत्तः समासशक्यः । किं तर्हि विभक्त्यर्थ एवेति भाष्ये पक्षान्तरमाह—अथवा विभक्त्यर्थ इति । तद्व्याचष्टे—कृत्स्नेति ॥ गृह्यत इति । स्वतन्त्रः सन् समासशक्य इत्यर्थः ॥ प्रकृत्यर्थोपसर्जनः प्रत्ययार्थ इति । स च संबन्धरूपः । सांसर्गिकविषयतानिरूपिता च तत्तस्वे प्रकारतेति भावः ॥ अव्ययेनापीति । अन्यथा पूरणगुणेति निषेधः स्यादित्यर्थः ॥ अव्ययशब्देन कृदव्ययमेव गृह्यत इति युक्त्यन्तरमप्युक्तं तत्रैव मैयेति दिक् ॥

(१३८३ आक्षेपवार्तिकम् ॥ ५ ॥)

॥ * ॥ विभक्त्यर्थाभिधानेद्रव्यस्य लिङ्गसंख्योपचारानुपपत्तिः ॥ * ॥

(व्याख्याभाष्यम्)

विभक्त्यर्थाभिधानेऽद्रव्यस्य लिङ्गसंख्याभ्यामुपचारोऽनुपपन्नः । बहुयवं बहुयवा । बहुयवः बहुयवौ बहुयवा इति ॥

अपर आह—विभक्त्यर्थाभिधाने द्रव्यस्य लिङ्गसंख्योपचारानुपपत्तिः । विभक्त्यर्थाभिधाने द्रव्यस्य ये लिङ्गसंख्ये ताभ्यां विभक्त्यर्थस्योपचारोऽनुपपन्नः। बहुयवं बहुयवा । बहुयवः बहुयवौ बहुयवा इति ॥

(प्रदीपः) **अद्रव्यस्येति** । असत्त्वभूतस्य विभक्त्यर्थस्य लिङ्गसंख्याभ्यां व्यवहारो नोपपद्यत इत्यर्थः ॥ **अपर इति** । अकारप्रश्लेषोऽत्र व्याख्याने नास्ति ॥

(उद्द्योतः) **लिङ्गसंख्याभ्यामिति** । इदमुपलक्षणं चित्रगुर्देवदत्त इति सामानाधिकरण्येन व्यवहारो न स्यादित्यपि बोध्यम् ॥

(आक्षेपभाष्यम्)

कथं ह्यन्यस्य लिङ्गसंख्याभ्यामन्यस्योपचारः स्यात् ?॥

(१३८४ समाधानवार्तिकम् ॥ ६ ॥)

॥ * ॥ सिद्धं तु यथा गुणवचनेषु ॥ * ॥

(व्याख्याभाष्यम्)

सिद्धमेतत् ॥ कथम् ?। यथा गुणवचनेषु ॥ कथं गुणवचनेषु ? ॥ गुणवचनेषूक्तम्—गुणवचनानां शब्दानामाश्रयतो लिङ्गवचनानि भवन्तीति । तद्यथा—शुक्लं वस्त्रं शुक्ला शाटी शुक्लः कम्बलः । शुक्लौ कम्बलौ । शुक्लाः कम्बला इति । यदसौ द्रव्यं श्रितो भवति गुणस्तस्य यल्लिङ्गं वचनं च तद्गुणस्यापि भवति । एवमिहापि यदसौ द्रव्यं श्रितो भवति विभक्त्यर्थः तस्य यल्लिङ्गं वचनं तत्समासस्यापि भविष्यति ॥

(प्रदीपः) **आश्रयत इति** । यदा पदावधिकमन्वाख्यानं तदा शुक्लो गुणोस्येति मतुब्लुका सामान्यमात्रे पदं संस्क्रियत इत्येकत्वनपुंसकत्वाश्रयेण पदप्रयोगे प्राप्ते **विशेषणानां चाजातेरिति** सूत्रेण गुणवचनानामाश्रयतो लिङ्गवचनानि प्रतिपादितानि । वाक्यसंस्कारे तु न्यायसिद्धानि आश्रयविशेषाश्रयेणैव पदसंस्कारात् । तत्र यद्यपि चित्रगुशब्देन संबन्धोभिधीयते तथाप्यभेदोपचारात् संबन्ध्यभिधीयते तत्र द्विष्ठत्वेपि संबन्धस्य प्रधानत्वात् स्वामिन एवाश्रयत्वं व्यवस्थाप्यत इति तद्गते लिङ्गसंख्ये भवतः न तु गवाश्रये ॥

(उद्द्योतः) **न्यायसिद्धानीति** । अत्र चेदमेव भाष्यं मानम् । अन्यथा गुणवचनेष्वस्य वाचनिकतया समासस्यातदारसूत्रोक्तरीत्या गुणवचनत्वाभावेन वचनाप्रवृत्तावसंगतिः । गुणवचनत्वे तु यथा-तथाशब्दासंगतिः स्पष्टैव ॥ **अभेदोपचारादिति** । आश्रयाभेदमापन्नविभक्त्यर्थ एव चित्रग्वादिपदैरुच्यत इति भावः ॥ **संबन्ध्यभिधीयत इति** । विशेष्यतया आश्रीयते चित्रगुर्देवदत्त इत्यादावित्यर्थः ॥ ननु गवामपि संबन्धित्वात्तद्गतलिङ्गसंख्ये किं न स्यातां तत्राह—**तत्र द्विष्ठत्वेपीति** । गवादिरूपस्वनिरूपितसंबन्धस्यैव बोधनेन स्वामिन एवाश्रयत्वात्तद्गतलिङ्गसंख्ये एव भवत इत्यर्थः । एवं च बहुव्रीहेः सामान्यशब्दत्वमेवेति विशेषज्ञानायानुप्रयोग आवश्यक इति भावः॥

(आक्षेपभाष्यम्)

यदि तर्हि विभक्त्यर्थोभिधीयते कृत्स्नः पदार्थः कथमभिहितो भवति सद्रव्यः सलिङ्गः ससंख्यश्च॥

(प्रदीपः) **यदि तर्हीति** । यथा शुक्लशब्देन कदाचिद्गुण उच्यते कदाचिद्गुणी तथा चित्रगुशब्देन केवलस्यापि संबन्धस्याभिधानं प्राप्नोति संबन्धिन एव तु सर्वदेष्यते तन्न सिध्यतीत्यर्थः ॥ कृत्स्न इत्युक्तं तदेव कात्स्न्यं प्रतिपाद्यते—**सद्रव्य इति** । द्रव्यशब्देन सत्त्वरूपोर्थ उच्यते ॥

(उद्द्योतः) ननु बहुव्रीहेः संबन्धिपरत्वस्योक्तत्वेन **यदि तर्हीति** भाष्यानुत्थानमाशङ्क्याह—**यथेति** । एवं च कथमभिहित इति भाष्यस्य सर्वदेत्यादिर्बोधः ॥ **द्रव्यशब्देनेति** । तदेव दर्शितं भाष्ये सलिङ्ग इत्यादिना ॥

(समाधानभाष्यम्)

अर्थग्रहणसामर्थ्यात् । इह "अनेकमन्यपदे" इतीयता सिद्धम् । कथं पुनः पदे नाम वृत्तिः स्यात् । पदं नाम शब्दः शब्दो ह्यपदः? । शब्दे ह्यसंभवादर्थे कार्यं विज्ञास्यते । सोयमेवं सिद्धे सति यदर्थग्रहणं करोति तस्यैतत्प्रयोजनं कृत्स्नः पदार्थो यथाभिधीयते सद्रव्यः सलिङ्गः ससंख्यश्चेति ॥

(प्रदीपः) **अर्थग्रहणसामर्थ्यादिति** । यदि विभक्त्यर्थस्यैव प्रधानस्य ग्रहणमभिमतं स्यात् तदार्थग्रहणं न कुर्याद् अन्तरेणाप्यर्थग्रहणमर्थस्यैव लाभादित्यर्थः ॥

(उद्द्योतः) **अर्थस्यैव लाभादिति** । स चार्थः प्राधान्याद्विभक्त्यर्थ एव ग्रहीष्यत इति भावः । अर्थग्रहणसामर्थ्याच्च संबन्धादिर्विभक्त्यर्थ आश्रयाभिन्न एव बुध्यत इति तत्त्वम् । एवं च पट्वादिशब्दवन्नियमेन गुणिपर एवायं न कदाचिदपि गुणपर इति भावः ॥

(आक्षेपभाष्यम्)

यदि तर्हि कृत्स्नः पदार्थोभिधीयते—लैङ्गाः सांख्याश्च विधयो न सिध्यन्ति ॥

(प्रदीपः) **यदि तर्हीति** । यथा बहुव्रीहिणा विभक्त्यर्थस्याभिधानात् षष्ठ्यादयो न भवन्ति एवं लिङ्गसंख्ययोरप्यभिधानात् तयोर्वाचकाः प्रत्यया न प्राप्नुवन्ति ॥

(उद्द्योतः) **यदितर्हीत्या**दि भाष्यमेकदेशिनो घटादिशब्देष्विव तदुपपत्तेः पञ्चकस्य सर्वत्र प्रातिपदिकार्थत्वात् ॥ **न प्राप्नुवन्तीति** । उक्तार्थानामप्रयोगादिति भावः ॥

(समाधानभाष्यम्)

उक्तं वा ॥ किमुक्तम्? । लैङ्गेषु तावदुक्तम् *सिद्धं तु स्त्रियाः प्रातिपदिकविशेषणात्स्वार्थे टाबादयः* इति ॥

सांख्येष्वप्युक्तम् ॥ किमुक्तम्? । कर्मादीनामनुक्ता एकत्वादय इति कृत्वा सांख्या भविष्यन्ति ॥

(प्रदीपः) **सिद्धं त्विति** । स्त्रियां यत् प्रातिपदिकं वर्तते तस्मात् टाबादयो भवन्तीत्यर्थः । ततश्च समासेनाभिहितेपि स्त्रीत्वे द्योतकाष्टाबादयो भवन्तीति दोषाभावः ॥ **कर्मादीनामिति** । चित्रगुरिति समासेन प्रातिपदिकार्थमात्रस्य कर्मादिशक्तिरहितस्यैकत्वादय उक्ताः ततः कर्मादिगतैकत्वप्रतिपादनाय वचनानि भवन्ति चित्रगुं पश्य चित्रगुणा कृतमिति ॥

(उद्द्योतः) **कर्मादिगतैकत्वेति** । दृश्यादिनिरूपितकर्मादिशक्तिविशिष्टप्रातिपदिकार्थगतैकत्व इत्यर्थः ॥

(आक्षेपभाष्यम्)

प्रथमा तर्हि न प्राप्नोति? ॥

(प्रदीपः) **प्रथमेति** । समासेन संख्याया अभिधानात् ॥

(उद्द्योतः) **समासेनेति** । प्रथमा हि प्रातिपदिकार्थगतसंख्यामात्राभिधायिनीति तत्सूत्रानुवृत्तमनभिहित इति तस्या एव विशेषणमिति भावः ॥

(समाधानभाष्यम्)

समयाद्भविष्यति ॥

(प्रदीपः) **समयादिति । परश्चेति नियमार्थमारब्धं**—न केवला प्रकृतिः प्रयोक्तव्या, न च केवलः प्रत्यय इति ॥

(आक्षेपभाष्यम्)

यदि सामयिकी न नियोगतः, अन्याः कस्मान्न भवन्ति? ॥

(प्रदीपः) **न नियोगत इति** । नियमेन । प्रतिनियतैव यदि न भवति विभक्तिः ततः समयपरिपालनाय द्वितीयादयोपि प्राप्नुवन्ति नियमकारणाभावादित्यर्थः ॥

(उद्द्योतः) **नियोगत** इत्यस्यार्थो **नियमेनेति** । नियमाभावमुपपादयति—**प्रतिनियतैवेति** । समयो हि सामान्यतो विभक्तिं बोधयति न प्रतिनियतां कांचिदिति भावः ॥ **यदीति** । यत इत्यर्थः । यतः प्रतिनियतैव समयान्न भवति तद्घटितसमयाभावादित्यर्थः ॥ **द्वितीयादयोपीति** । अर्थाभावेपि नियम (समय) परिपालनाय विभक्तिश्चेत्प्रथमैवेति नियमाभावादिति भावः ॥

(समाधानभाष्यम्)

कर्मादीनामभावात् ॥

(प्रदीपः) **कर्मादीनामभावादिति** । कर्मण्येव द्वितीयेत्येवं कर्मादिषु द्वितीयादीनां नियतत्वात्तदभावे तासामभावः ॥

(आक्षेपभाष्यम्)

षष्ठी तर्हि प्राप्नोति? ॥

(प्रदीपः) **षष्ठी तर्हीति** । कर्मादीनामभावः शेषः स चात्रास्तीति भावः ॥

(समाधानभाष्यम्)

शेषलक्षणा षष्ठी, अशेषत्वान्न भविष्यति ॥

(प्रदीपः) **अशेषत्वादिति** । प्रातिपदिकार्थमात्रस्य प्रथमाविधावुपयोगान्नास्ति शेषत्वमित्यर्थः ॥

(उद्द्योतः) **प्रातिपदिकेति** । कर्मादिप्रातिपदिकार्थव्यतिरिक्तो हि शेष इत्यर्थः ॥

(आक्षेपभाष्यम्)

एवमपि व्यतिकरः प्राप्नोति—एकस्मिन्नपि द्विवचनबहुवचने प्राप्नुतः, द्वयोरप्येकवचनबहुवचने, बहुष्वप्येकवचनद्विवचने? ॥

(प्रदीपः) **एवमपीति** । समयात् प्रथमायामिष्यमाणायां वचनस्य व्यतिकरप्रसङ्गः ॥

(उद्द्योतः) **व्यतिकरो** व्यत्यासः ॥

(समाधानभाष्यम्)

अर्थतो व्यवस्था भविष्यति ॥

(प्रदीपः) **अर्थत इति** । यथान्यत्रैकत्वादिष्वेकवचनादीनि दृष्टानि तथैवात्रापि भवन्ति । एवं हि समयश्च परिपालितो भवत्यर्थश्चानुसृतः ॥

(उद्द्योतः) अर्थाभावेपि समयाद्भविष्यतीत्युक्त्वाऽर्थतो व्यवस्थेत्युक्तिरसंगतेत्यत आह—**यथान्यत्रेति** । विरुद्धविभक्त्यपेक्षया-नुवादकविभक्तेर्न्याय्यत्वमिति भावः ॥

(समाधानान्तरभाष्यम्)

अथ वा संख्या नामेयं परप्रधाना । संख्येयमनया विशेष्यम् । यदि चात्र प्रथमा न स्यात्, संख्येयमविशेषितं स्यात् ॥

(प्रदीपः) **अथ वेति** । असंकरं प्रथमाविधानं प्रकारान्तरेण प्रतिपादयति ॥ यदा चित्रगुरित्येकत्वविशिष्टः प्रातिपदिकार्थः प्रतिपिपादयिषितः तदा विभक्त्या विनासौ न शक्यते प्रत्याययितुमिति प्रथमैकवचनं विधेयम् । एवं द्वित्वबहुत्वयोर्द्विवचनबहुवचनविधिः ॥ **परप्रधानेति** । संख्येयप्रधानेत्यर्थः ॥

(उद्द्योतः) भाष्ये—**अथवा संख्या नामेयमिति** । इयं यद्वैशिष्ट्येन प्रातिपदिकार्थः प्रतिपिपादयिषितः सा **परप्रधाना** इतरपरिच्छेदिकैव । तदेवाह—**संख्येयमनया विशेष्यमिति** । **संख्येयं** द्रव्यं प्रातिपदिकार्थो **अनया** संख्यया **विशेष्यं** परिच्छेद्यतया बोधनीयम् । एवं च यावत्संख्यं संख्येयं तावत्संख्याप्रतिपादिका विभक्तिरुचिता । विभक्तिमन्तरा तस्या अप्रतिपत्तेरिति भावः ॥ **यदि चात्र प्रथमा न स्यादिति** । असंकरेणेत्यर्थः । तदाह—

यदा चित्रगुरिति । द्वावित्यादौ यथानुवादकं वचनं नियमेन तथात्रापीति भावः ॥

(समाधानान्तरभाष्यम्)

अथ वा वक्ष्यत्येतद् वचनग्रहणस्य प्रयोजनम्—उक्तेष्वप्येकत्वादिषु प्रथमा यथा स्यात् ॥

(उद्योतः) भाष्ये—अथवा वक्ष्यतीति । एवं चोक्तेषु तेष्वसंकरेणैव सेति भावः ॥

(आक्षेपभाष्यम्)

एवमपि षष्ठी प्राप्नोति ॥ किं कारणम् ? । व्यभिचरत्येव ह्ययं समासो लिङ्गसंख्ये, षष्ठ्यर्थं पुनर्न व्यभिचरति ? ॥

(प्रदीपः) **एवमपीति** । षष्ठ्यर्थस्यात्र भावात् ॥ **व्यभिचरतीति** । लिङ्गान्तरसंख्यान्तरयोगेन्यलिङ्गसंख्यापरित्यागात् ॥

(उद्योतः) **षष्ठ्यर्थस्येति** । अयं भावः—प्रथमाया समभिव्याहृतप्रातिपदिकस्य चित्रगोरूपस्य प्रवृत्तिनिमित्ततदाश्रयरूपस्वार्थबोधनसामर्थ्यप्यतथाभूतसंवन्धबोधे सामर्थ्यं नेति तद्बोधाय सम्बन्धस्योक्तत्वेप्यनुवादिका षष्ठ्येव स्यान्न प्रथमा प्रातिपदिकार्थमात्राभावादिति ॥ **लिङ्गान्तरेति** । एवं च षष्ठ्यर्थस्य चित्रगुरित्येवंरूपे बहुव्रीहावव्यभिचरितत्वेन नियमेन षष्ठ्येव प्राप्नोतीत्यर्थ इति भावः ॥

(समाधानभाष्यम्)

अभिहितः सोर्थोन्तर्भूतः प्रातिपदिकार्थः संपन्नः। तत्र प्रातिपदिकार्थे प्रथमेति प्रथमा भविष्यति ॥

(प्रदीपः) **अभिहित इति** । संबन्धस्य प्रातिपदिकार्थरूपत्वात् षष्ठ्यर्थता नास्तीत्यर्थः ॥

(उद्योतः) **प्रातिपदिकार्थरूपत्वादिति** ॥ तत्र चाभिहितत्वं हेतुः । एवं च प्रातिपदिकार्थत्वात्तद्बोधिका प्रथमेति भावः । एतद् ध्वनयितुमेवाभिहितः सोर्थ इत्युक्तम् । तेन च षष्ठ्यप्राप्तिबीजमप्युक्तम्, अनभिहिते शेष एव षष्ठीविधानात् । अत एव घटशब्दान्न षष्ठी । अन्यथा तत्रापि घटत्वसंबन्धस्य नियमेन भानात्षष्ठी स्यात् ॥ अन्तर्भूत इत्यस्य प्रवृत्तिनिमित्तत्वं तदाश्रयत्वं वा प्रतिपन्न इत्यर्थः ॥ ननु षष्ठ्या एवापत्तिः कथं, प्राप्तोदक इत्यादौ द्वितीयादीनामप्यापत्तेरिति चेन्न । तेषु प्राप्तोदककर्मत्वेव बोधस्तत्र विशेष्ये तन्निरूपकत्वसंबन्धेन विशेषणमादाय पर्यवसानमिति द्वितीयादिप्रयोजककर्मत्वादेरबोधेन तदप्राप्तेः। षष्ठ्यर्थस्य तु षष्ठीप्रयोजकरूपेणैव भानमित्याशयात् ॥

(आक्षेपभाष्यम्)

न तर्हीदानीमिदं भवति—चित्रगोर्देवदत्तस्येति॥

(प्रदीपः) सर्व एवात्र संबन्धोन्तर्भूतत्वात् प्रातिपदिकार्थतां गत इति मत्वा पृच्छति—**न तर्हीति** ॥

(समाधानभाष्यम्)

भवति बाह्यमर्थमपेक्ष्य षष्ठी ॥

(प्रदीपः) **भवति बाह्यमिति** । गोभिरन्यपदार्थस्य यः संवन्धः स एव समासेन्तर्भूतो न तु सर्वः ॥

(परिगणनाधिकरणम्)

(भाष्यम्) **परिगणनं कर्तव्यम् ॥**

(१३८५ परिगणनवार्तिकम् ॥ ७ ॥)

॥ * ॥ बहुव्रीहिः समानाधिकरणानाम् ॥ * ॥

(व्याख्याभाष्यम्)

समानाधिकरणानां बहुव्रीहिर्वक्तव्यः॥ किं प्रयोजनम् ? । व्यधिकरणानां मा भूदिति । पञ्चभिर्भुक्तमस्येति ॥

(प्रदीपः) **बहुव्रीहिरिति** । भाष्यकारेण त्रिकतः शेषो गृह्यत इत्ययमर्थः साधितः । वार्तिककारेण तु वचनेन प्रतिपाद्यते ॥

(उद्योतः) **वचनेनेति** । समानाधिकरणानाम्* *अप्रथमार्थे इति वचनाभ्यां त्रिकतः शेषपक्षीयोर्थः प्रतिपाद्यत इत्यर्थः । शेषग्रहणं तु पठतोर्थतो वा शेषबोधकं स्यात् । तत्र फलाभावो दोषश्चेति वार्तिकतात्पर्यम् ॥

(१३८६ परिगणनवार्तिकम् ॥ ८ ॥)

॥ * ॥ अव्ययानां च ॥ * ॥

(व्याख्याभाष्यम्)

अव्ययानां च बहुव्रीहिर्वक्तव्यः । उच्चैर्मुखमस्येति उच्चैर्मुखः नीचैर्मुखः ॥

(प्रदीपः) **उच्चैर्मुख इति** । उच्चैःशब्दस्याधिकरणप्रधानत्वाद्वैयधिकरण्यमिति वचनम् ॥

(१३८७ परिगणनवार्तिकम् ॥ ९ ॥)

॥ * ॥ सप्तम्युपमानपूर्व[पद]स्योत्तरपदलोपश्च ॥ * ॥

(व्याख्याभाष्यम्)

सप्तमीपूर्वस्योपमानपूर्वस्य च बहुव्रीहिर्वक्तव्यः, उत्तरपदस्य च लोपो वक्तव्यः॥ कण्ठेस्थः कालोस्य कण्ठेकालः । उष्ट्रमुखमिव मुखमस्य उष्ट्रमुखः । खरमुखः ॥

(प्रदीपः) **कण्ठेस्थ इति** । **सुपिस्थ** इति कः । **अमूर्धमस्तकादित्यलुक्** । समासेत्र सिद्धे वचनमुत्तरपदलोपार्थम् ॥ **उष्ट्रमुखमिवेति** । अवयवधर्मेण समुदायस्य । व्यपदेशाद् उष्ट्रस्योपमानतेति उपमानपूर्व उष्ट्रमुखशब्दः उपमानोपमेयवृत्तित्वात् पदयोर्वैयधिकरण्यमत्रेति वचनमुत्तरपदलोपार्थं च ॥

(उद्योतः) **अमूर्धेति** । **खेचभापायामिति** तु **अनन्तरस्येति** न्यायेन तत्पुरुषे कृतीत्यस्यैव बाधकमिति भावः ॥ उत्तर-

पदलोपार्थमिति । कण्ठस्थकालनिवृत्त्यर्थमित्यर्थः ॥ मुखस्यैवोपमानत्वेनोष्ट्रमुखशब्दस्योपमानपूर्वत्वं कथमत आह—अवयवधर्मेणेति । मुखगतोपमानत्वेनोष्ट्रस्यापि व्यवहारादिति भावः ॥ वैयधिकरण्यमिति । वाक्ये समासे च साद्दश्यसंबन्धेनान्वयः ॥ इवशब्दस्तथा संबन्धेनान्वयस्यैव बोधक इत्यभिमानः । उपमानानीति सूत्रभाष्योक्तरीत्या सामानाधिकरण्यमस्त्येवेत्यत आह—उत्तरपदेति ॥

(१३८८ परिगणनवार्तिकम् ॥ १० ॥)

॥ * ॥ समुदायविकारषष्ठ्याश्च ॥ * ॥

(व्याख्याभाष्यम्)

समुदायविकारषष्ठ्याश्च बहुव्रीहिर्वक्तव्यः । उत्तरपदस्य च लोपो वक्तव्यः । केशसमाहारश्चूडा अस्य केशचूडः । सुवर्णविकारोलंकारो यस्य सुवर्णालंकारः ॥

(प्रदीपः) समुदायविकारषष्ठ्या इति । समुदायावयवसंबन्धे प्रकृतिविकारसंबन्धे च या षष्ठी तदन्तायत् परं तदन्तस्य शब्दान्तरेण सह बहुव्रीहिरित्यर्थः ॥

(उद्द्योतः) समुदायविकारवाचकपदस्य षष्ठ्यन्तस्योत्तरपदेन समास इत्यर्थभ्रमं वारयति—समुदायावयवसंबन्ध इति ॥

(१३८९ परिगणनवार्तिकम् ॥ ११ ॥)

॥ * ॥ प्रादिभ्यो धातुजस्य वा ॥ * ॥

(व्याख्याभाष्यम्)

प्रादिभ्यो धातुजस्य बहुव्रीहिर्वक्तव्यः । उत्तरपदस्य च वा लोपो वक्तव्यः । प्रपतितपर्णः प्रपर्णः । प्रपतितपलाशः प्रपलाशः ॥

(१३९० परिगणनवार्तिकम् ॥ १२ ॥)

॥ * ॥ नञोस्त्यर्थानां च ॥ * ॥

(व्याख्याभाष्यम्)

नञोस्त्यर्थानां बहुव्रीहिर्वक्तव्यः । उत्तरपदस्य च वा लोपो वक्तव्यः । अविद्यमानः पुत्रोस्य अविद्यमानपुत्रः अपुत्रः । अविद्यमानभार्यः अभार्यः ॥

(आक्षेपभाष्यम्)

तत्तर्हीदं बहु वक्तव्यम् ? ॥

(१३९१ परिगणननिराकरणवार्तिकम् ॥ १३ ॥)

॥ * ॥ न वाऽनभिधानादसमानाधिकरणेषु समाससंज्ञाभावः ॥ * ॥

(व्याख्याभाष्यम्)

नवा वक्तव्यम् ॥ असमानाधिकरणानां बहुव्रीहिः कस्मान्न भवति—पञ्चभिर्भुक्तमस्येति ? । अनभिधानात् । तच्चावश्यमनभिधानमाश्रयितव्यम् । क्रियमाणेपि परिगणने यत्राभिधानं न भवति तत्र न बहुव्रीहिः । यथा पञ्च भुक्तवन्तोस्येति ॥

(उद्द्योतः) भाष्ये—यथा पञ्च भुक्तवन्तोस्येति । अनेन त्रिकतः शेष इत्यर्थेपि शेषग्रहणं प्रत्याख्यातं तुल्यन्यायादिति बोध्यम् ॥

(आक्षेपभाष्यम्)

अथैतस्मिन्सत्यनभिधाने यदि वृत्तिपरिगणनं क्रियेत तर्हि वर्तिपरिगणनमपि कर्तव्यम् ॥

(प्रदीपः) अथैतस्मिन्निति । अनभिधानमभ्युपगम्यापि यदि मन्दबुद्धिव्युत्पादनाय परिगणनं क्रियते तदार्थपरिगणनमपि कर्तव्यम् । वर्तनं वर्तः समासः, स विद्यते यस्मिन्नर्थे स वर्ती ॥

(उद्द्योतः) इदानीमनभिधाने सत्यपि समानाधिकरणानामित्यादिवचनारम्भेऽन्यस्यापि कर्तव्यत्वमापादयति—भाष्ये—अथैतस्मिन्नित्यादिना । वृत्तिपरिगणनं वृत्त्याश्रयाणां परिगणनम् ॥

(प्रत्याक्षेपभाष्यम्)

तत्कथं कर्तव्यम् ? ॥

(१३९२ समाधानवार्तिकम् ॥ १४ ॥)

॥ * ॥ अर्थनियमे मत्वर्थग्रहणम् ॥ * ॥

(व्याख्याभाष्यम्)

अर्थनियमे मत्वर्थग्रहणं कर्तव्यम् । मत्वर्थे यः, स बहुव्रीहिरिति वक्तव्यम् । इह मा भूत्—कष्टं श्रितमनेनेति ॥

(प्रदीपः) मत्वर्थग्रहणमिति । षष्ठ्यर्थः सप्तम्यर्थश्च मत्वर्थः ॥

(उद्द्योतः) कष्टं श्रितमनेनेति । गत्यर्थेति वा आदिकर्मणीति वा भावे क्तः । यदि कर्तरि कर्मणि वा क्तः स्यात् तदोत्तरवचनाभ्यामत्र समासः स्यादेव ऊढरथादिवदिवेति बोध्यम्, मत्वर्थे वर्तमानमनेकमित्युक्ते सामानाधिकरण्यमपि लब्धमेवेति बोध्यम् ॥

(१३९३ वार्तिकम् ॥ १५ ॥)

॥ * ॥ तथा चोत्तरस्य वचनार्थः ॥ * ॥

(भाष्यम्) **एवं च कृत्वोत्तरस्य योगस्य वचनार्थ उपपन्नो भवति ॥**

(वार्तिकस्योत्तरपदव्याख्याभाष्यम्)

केचित्तावदाहुः—'यद्वृत्तिसूत्रे' इति "संख्ययाव्ययासन्नादूराधिकसंख्याः संख्येये" इति ॥

(प्रदीपः) संख्ययेति । संख्येयस्य वार्थस्य चान्यपदार्थत्वात् सिद्धे समासे उत्तरसूत्रमनर्थकं स्यात् । यदा त्वनेन मत्वर्थे समासस्तदा सार्थकमित्यर्थः ॥

(उद्द्योतः) तथा चोत्तरस्येति वाक्यं केनचित्संख्ययेति सञ्ज्ञाभिप्रायतया व्याख्यातं तन्निवध्नाति—भाष्ये—केचिदिति । अत्र प्रथमान्तसंख्यापदं समानाधिकरणानामित्युक्तावपि व्यर्थं स्यात् । द्वौ वा त्रयो वेत्यादावेकत्रैव समुदाये द्वित्वत्रित्वविकल्पप्रतीतेर्यथाकथंचित्सत्त्वात् । एवं द्विदशा इत्यत्राप्यूह्यम् । अत्र पक्षे उत्तरस्य योगस्य यद्वचनं करणं तस्यार्थः फलमुपपन्नमित्यक्षरार्थः ॥

(सिद्धान्तिमतान्तरभाष्यम्)

अपर आहुः—'यद्वार्तिके' इति ॥

(१३९४ व्याख्येयवार्तिकम् ॥ १६ ॥)

॥ * ॥ कर्मवचनेनाप्रथमायाः ॥ * ॥

(व्याख्याभाष्यम्)

कर्मवचनेनाप्रथमाया बहुव्रीहिर्वक्तव्यः । ऊढो रथो येन ऊढरथोऽनड्वान् । उपहृतः पशू रुद्राय उपहृतपशू रुद्रः । उद्धृत ओदनः स्थाल्याः उद्धृतौदना स्थाली ॥

(प्रदीपः) व्याख्यानान्तरमाह—**अपर इति** ॥ **कर्मवचनेनाप्रथमाया इति** । प्रथमार्थं वर्जयित्वा सर्वत्रान्यपदार्थे कर्मवाचिना समासो भवतीत्यर्थः । इदञ्च वार्तिकमेवमुपपद्यते यदि मत्वर्थे बहुव्रीहिर्भवति । अन्यथैतदवक्तव्यं स्यात् । आद्यमेव तु युक्तं व्याख्यानम् । नहि वार्तिककारः स्ववचनमेव ज्ञापकत्वेनोपन्यस्यति ॥ **ऊढरथ इति** । रथशब्दः कर्मवचन ऊढशब्देन सामानाधिकरण्यात् ॥

(उद्द्योतः) अस्य कबभावार्थमावश्यकत्वमभिप्रेत्य स्वयमाह—**यद्वार्तिके इति** । तदेव दर्शयति—**कर्मवचनेनेति** । कर्मवचनेनेत्यस्यायमर्थः—प्रथमाभिन्नविभक्तेरर्थे कर्मबोधकेन शब्देन प्रत्यासत्त्या कर्मवाचकस्य समास इति तेन व्यधिकरणे न दोषः । अन्यथा मत्वर्थे इत्यस्याभावे ॥ **अवक्तव्यमिति** । सूत्रेणैव सिद्धेरिति भावः । **आद्यमेव त्वित्यादिरुपन्यस्यतीत्यन्तः** कैयटग्रन्थस्तु चिन्त्यः । अस्यान्यवार्तिककारीयत्वात् लुप्ताख्यातेषु च वचनप्रामाण्यादिति समर्थसूत्रस्थवार्तिकस्य वार्तिकवचनप्रामाण्यादिति भाष्ये व्याख्यानाच्च । एवं च सर्वथा पञ्चभिर्भुक्तवन्तोऽस्येत्यत्र समासवारणायानभिधानस्यावश्यकतया पञ्चभिर्भुक्तमस्य वृष्टे देवे गतस्तत्र गतं पश्येत्यादावप्यनभिधानमाश्रित्य वार्तिकानां शेषग्रहणस्य च प्रत्याख्यानमेव युक्तमिति भाष्याशयः । अव्ययानां चेत्यपि न कार्यम्, उच्चैरादीनां वृत्तिविषये शक्तिमत्प्रधानत्वाङ्गीकारेण सूत्रेण सिद्धेः । अन्यान्यप्यनिष्टांशेऽनभिधानमाश्रित्य प्रत्याख्येयानीति दिक् ॥

(आक्षेपभाष्यम्)

यदि कर्मवचनेनेत्युच्यते, अथ कर्तृवचनेन कथम्—प्राप्तमुदकं ग्रामं प्राप्तोदको ग्रामः । आगता अतिथयो ग्राममागतातिथिर्ग्रामः ? ॥

(१३९५ वार्तिकम् ॥ १७ ॥)

॥ * ॥ कर्तृवचनेनापि ॥ * ॥

(व्याख्याभाष्यम्)

कर्तृवचनेनापीति वक्तव्यम् ॥

(आक्षेपभाष्यम्)

अप्रथमाया इति किमर्थम् ? ॥

(समाधानभाष्यम्)

वृष्टे देवे गतः ॥

(आक्षेपभाष्यम्)

अथ 'अप्रथमायाः' इत्युच्यमाने इह कस्मान्न भवति—वृष्टे देवे गतं पश्यति ॥

(समाधानभाष्यम्)

बहिरङ्गा अत्राप्रथमा ॥

(प्रदीपः) **बहिरङ्गेति** । वर्तिपदार्थनिमित्तान्तरङ्गा वाक्यपदार्थापेक्षा तु बहिरङ्गेति न गृह्यते असिद्धत्वादित्यर्थः ॥

(१३९६ समासाक्षेपवार्तिकम् ॥ १८ ॥)

(दृष्टानुपपत्तिपरिहाराधिकरणम्)

॥ * ॥ सुबधिकारेऽस्तिक्षीरादिवचनम् ॥ * ॥

(व्याख्याभाष्यम्)

सुबधिकारेऽस्तिक्षीरेत्युपसंख्यानं कर्तव्यम् । अस्तिक्षीरा ब्राह्मणी ॥

(उद्द्योतः) अस्तीति तिङन्तमेवेति मत्वा भाष्ये **सुबधिकार इति** ॥

(आक्षेपभाष्यम्)

तत्तर्हि वक्तव्यम् ? ॥

(१३९७ समाधानवार्तिकम् ॥ १९ ॥)

॥ * ॥ नवाऽव्ययत्वात् ॥ * ॥

(भाष्यम्) **नवा कर्तव्यम् । किं कारणम् ? । अव्ययत्वात् । अव्ययमेषोऽस्तिशब्दः । नैषोऽस्तेर्लट् । कथमव्ययत्वम् ? । उपसर्गविभक्तिस्वरप्रतिरूपकाश्च निपाता भवन्तीति निपातसंज्ञा । निपातोऽव्ययमित्यव्ययसंज्ञा ॥**

(प्रदीपः) **उपसर्गविभक्तीति** । स्वरादिष्वस्तिशब्दपाठमनपेक्ष्यैतदुक्तम् ॥

(उद्द्योतः) **अनपेक्ष्येति** । सोऽप्रामाणिक इति तत्त्वम् । एवं च तस्यातिङन्तत्वात् प्रातिपदिकत्वेन सुबन्तत्वमिति सूत्रेणैव सिद्धमिति भावः ॥

(किंसब्रह्मचारिशब्दार्थाधिकरणम्)

आक्षेपभाष्यम्)

अथ किंसब्रह्मचारीति कोऽयं समासः ? ॥

(समाधानभाष्यम्)

बहुव्रीहिरित्याह ॥

(आक्षेपभाष्यम्)

कोस्य विग्रहः ? ॥

(समाधानभाष्यम्)

के सब्रह्मचारिणोस्येति ॥

(आक्षेपभाष्यम्)

यद्येवं कठ इति प्रतिवचनं नोपपद्यते । न ह्यन्यत्पृष्टेनान्यदाख्येयम् ॥

(प्रदीपः) प्रतिवचनमिति । वर्तिपदार्था बहुत्वसंख्यायुक्ताः पृष्टास्ततश्चैकत्वसंख्यायुक्तेनान्यपदार्थविशेषणेन प्रतिवचनं नोपपद्यत इत्यर्थः ॥

(उद्द्योतः) अन्यपदार्थविशेषणेनेति । अन्यपदार्थो विशेष्यते विशेष्येऽवस्थाप्यतेऽनेन तादृशेन कठ इति शब्देनोत्तरं नोपपद्यते इत्यर्थः ॥

(समाधानभाष्यम्)

एवं तर्ह्येवं विग्रहः करिष्यते—केषां सब्रह्मचारी किंसब्रह्मचारीति ॥

(प्रदीपः) इष्टसमासस्थापनाय दिगन्तराणि निराकर्तुमुपन्यस्यति—एवं तर्हीति ॥

(उद्द्योतः) दिगन्तराणि प्रकारान्तराणि ॥

(समाधानबाधकभाष्यम्)

प्रतिवचनं चैवं नोपपद्यते । स्वरे च दोषो भवति—किंसब्रह्मचारीत्येवं स्वरः प्रसज्येत, किंसब्रह्मचारीति चेष्यते ॥

(प्रदीपः) प्रतिवचनमिति । कठानामिति प्रतिवचनेन भाव्यं न तु कठ इत्यनेनेत्यर्थः ॥ स्वर इति । अन्तोदात्तः स्याद् आद्युदात्तश्चेष्यत इत्यर्थः ॥

(समाधानान्तरभाष्यम्)

एवं तर्ह्येवं विग्रहः करिष्यते—कः सब्रह्मचारी किंसब्रह्मचारीति ॥

(प्रदीपः) कः सब्रह्मचारीति । सुप्सुपेति समासं मन्यते । विशेषणविशेष्यभावाभावात्तु विशेषणसमासो नास्ति॥

(उद्द्योतः) विशेषणविशेष्यभावाभावात्त्विति । परिच्छेद्यपरिच्छेदकभावो विशेष्यविशेषणभाव इत्यभिमानः ॥ वस्तुतो विषयताविशेषत्वरूपमेव तत्र तन्निविष्टमिति तेनापि समास इति चिन्त्यम् ॥

(समाधानान्तरबाधकभाष्यम्)

भवेत्प्रतिवचनमुपपन्नम् । स्वरे तु दोषो भवति ॥

(समाधानभाष्यम्)

एवं तर्ह्येवं विग्रहः करिष्यते—कः सब्रह्मचारी तव किंसब्रह्मचारी त्वमिति ॥

(प्रदीपः) कः सब्रह्मचारी तवेति । एकस्मिन्पृष्टे एकवचनेन प्रतिवचनमुपपद्यते ॥

(प्रागुक्तपक्षाङ्गीकारभाष्यम्)

अथ वा पुनरस्त्वयमेव विग्रहः—के सब्रह्मचारिणोस्येति ॥

(प्रदीपः) अत्रापि पक्षे कठ इति प्रतिवचनं व्यधिकरणं प्राप्नोति । अहं कठ इति सामानाधिकरण्यं दृश्यत इति विशेषाभावं मत्वाह—अथवेति ॥

(उद्द्योतः) व्यधिकरणं प्राप्नोतीति । प्रश्नविषयेणेति शेषः ॥ तत्र हेतुमाह—अहं कठ इति । यतोऽहमित्यनेन सामानाधिकरण्यमतस्तेन व्यधिकरणमित्यर्थः ॥ विशेषाभावमिति । प्रतिवचनानुपपत्तिपरिहाररूपस्य विशेषस्याभावमित्यर्थः ॥

(आक्षेपस्मारणभाष्यम्)

ननु चोक्तम्—कठ इति प्रतिवचनं नोपपद्यत इति ॥

(समाधानभाष्यम्)

नैष दोषः । अग्नौकरवाणिन्यायेन भविष्यति । तद्यथा—कश्चित्कंचिदाह—अग्नौकरवाणीति । स आह—कुर्विति । कर्तर्यनुज्ञाते कर्माप्यनुज्ञातं भवति ॥ अपर आह—अग्नौ करिष्य इति । क्रियतामिति कर्मण्यनुज्ञाते कर्ताप्यनुज्ञातो भवति । यथैव खल्वपि—के सब्रह्मचारिणोस्येति ? । 'कठाः' इत्युक्ते संबन्धादेतद्गम्यते-'नूनमयमपि कठः' इति । एवं 'कठ इत्युक्ते संबन्धादेतद्गन्तव्यं 'नूनं तेपि कठाः' इति । न खल्वपि ते समासेन शक्याः प्रतिनिर्देष्टुम् । उपसर्जनं हि ते भवन्ति ॥

(प्रदीपः) अग्नौकरवाणिन्यायेनेति । अग्नौ करवाणीति यद्वाक्यं तदनुकरणमेतत् ॥ कर्मापीति । सकर्मकत्वात् करोतिक्रियायाः ॥ एवं कठ इति । नहि तेषां कठत्वेन विना तस्य कठत्वोपपत्तिः । तथा हि—समाने ब्रह्मणि व्रतचारी सब्रह्मचारी कथ्यते । ततश्च तस्यैकचरणाध्ययनापेक्षं सब्रह्मचारित्वम् ॥ न खल्वपीति । वर्तिपदार्थानामुपसर्जनत्वात्तदुपलक्षितस्यान्यपदार्थस्य प्राधान्यात् किंसब्रह्मचारिशब्देन समासेन तेषामभिधानाभावात् कठा इति बहुवचनान्तं प्रतिवचनं न कदाचिद्भवतीत्यर्थः । यदा तु के सब्रह्मचारिणोस्येति वाक्येन प्रश्नः क्रियते न तु समासेन तदा कठा इत्येव प्रतिवचनम् ॥

(उद्द्योतः) अनुकरणमिति । एवं च तद्विषयो न्याय इति मध्यमपदलोपी समासः ॥ यत्त्वनुकरणस्य गतित्वात्समास इति । तन्न कृभ्वस्तियोग एव तत्प्रवृत्तेः ॥ भाष्ये—अग्नौ करवाणीत्यस्याग्नौ हविः करवाणीत्यर्थः ॥ कर्तर्यनुज्ञात इति । कुरु इत्यत्र कर्तरि लोट् । एवं च तात्पर्यतः प्रधानस्य कर्तुरेवानुज्ञा भवति इति भावः ॥ कर्मापीति । कर्मकारकमित्यर्थः । तदाह—सकर्मकत्वा-

दिति । दृष्टान्तान्तरमप्याह—भाष्ये—यथैव खल्वपीति ॥ दार्ष्टान्तिकमाह—एवमिति ॥ नहि तेषामिति । कठ इत्यस्य कठशाखाध्येतेत्यर्थादिति भावः ॥ चरणं शाखा । तथा च तस्य प्रश्नस्यार्थमिदमुत्तरमिति बोध्यम् ॥ नन्वसमासेन प्रश्न इव समासेन प्रश्नेपि बहुवचनान्तमुत्तरं कुतो नेत्यत आह—भाष्ये—न खल्वपीति । सब्रह्मचारिणः समासेन प्रतिनिर्देष्टुं प्राधान्येन बोधयितुमशक्या अतः समासेन प्रश्ने कठा इत्युत्तरं इत्यर्थः । प्रश्नवाक्ये यत्प्रधानं तद्विषयं यथाकथञ्चिज्जिज्ञासानिवर्तकमुत्तरमिति तात्पर्यम् ॥ तदाह—वर्तिपदेति ॥

(अर्धतृतीयादिशब्दार्थाधिकरणम्)

(आक्षेपभाष्यम्)

अथार्धतृतीया इति कोयं समासः? ॥

(समाधानभाष्यम्)

बहुव्रीहिरित्याह ॥

(आक्षेपभाष्यम्)

कोस्य विग्रहः? ॥

(समाधानभाष्यम्)

अर्धं तृतीयमेषामिति ॥

(आक्षेपभाष्यम्)

कः समासार्थः । समासार्थो नोपपद्यते । अन्यपदार्थो हि नाम स भवति, येषां पदानां समासस्ततोन्यस्य पदस्यार्थोन्यपदार्थः? ॥

(प्रदीपः) कः समासार्थ इति । वर्तिपदार्थव्यतिरिक्तेनान्यपदार्थेन भाव्यम् । इह च बहुत्वान्यथानुपपत्त्या क्रियायां च वर्तिपदार्थस्याप्यन्तर्भावादन्यपदार्थो नोपपद्यते ॥

(उद्योतः) कः समासार्थ इति वाक्यं न कोपीत्यर्थाभिप्रायेण भगवान्विवृणोति—समासार्थो नोपपद्यत इति ॥ वर्त्तिपदार्थस्याप्यन्तर्भावादिति । बहुत्वान्यथानुपपत्त्या क्रियायां वर्त्तिपदार्थस्याप्यन्वयादित्यर्थः । अन्यपदार्थशब्दस्यान्यपदस्यैव योर्थः न तु स्वपदस्यापीत्यर्थ इति भावः ॥

(समाधानभाष्यम्)

एवं तर्ह्येवं विग्रहः करिष्यते—अर्धं तृतीयमनयोरिति ॥

(आक्षेपभाष्यम्)

एवमपि कः षष्ठ्यर्थः । षष्ठ्यर्थो नोपपद्यते । किं हि तयोरर्धं भवति? ॥

(प्रदीपः) किं हि तयोरिति । तृतीयस्य हि तदर्धमिति द्वाभ्यां तस्यावयवावयविभावलक्षणः संबन्धो नास्ति स्वस्वामिसंबन्धे चात्रानभिधानाद् बहुव्रीहिर्न भवति । समासस्यानुपपत्तिचोदनाद् मूलाभावाद् द्विवचनप्रसङ्गो न चोदितः ॥

(उद्योतः) अत्र अर्धतृतीया इत्यत्र ॥ द्विवचनं स्यादिति कुतो नोक्तमत आह—समासस्येति ॥

(प्रथमोक्तविग्रहाभ्युपगमभाष्यम्)

अस्तु तर्ह्ययमेव विग्रहः—अर्धं तृतीयमेषामिति ॥

(आक्षेपस्मारणभाष्यम्)

ननु चोक्तम्—'समासार्थो नोपपद्यते' इति ॥

(समाधानभाष्यम्)

नैष दोषः । अवयवेन विग्रहः । समुदायः समासार्थः ॥

(प्रदीपः) अवयवेनेति । अर्धस्य द्वयोश्च यः समुदायः स समासार्थः । समुदायावयवानां च कदाचिद्भेदविवक्षा कदाचिदभेदविवक्षा । यथा—ब्राह्मणानां संघः । संघीभवन्ति ब्राह्मणा इति ॥

(उद्योतः) अवयवेन विग्रह इति । अवयवार्थेन वाक्यमित्यर्थः । वर्तिपदार्थोवयव इति यावत् ॥ नन्वर्धस्य द्वयोश्चेत्यनुपपन्नं समुदायस्यावयवानतिरिक्ततया अर्द्धं द्वयं च समुदाय इत्येवोचितमवयवेन विग्रहः समुदायः समासार्थ इति चायुक्तमत आह—समुदायावयवानां चेति । समुदायश्चान्यपदस्यैवार्थो न तु समस्यमानपदस्य । स चावयवेभ्यो भिन्नोऽत्रान्यपदार्थः अवयवगतबाहुल्यस्य च तत्रारोपाद्बहुवचनमिति भावः ॥

(आक्षेपभाष्यम्)

यद्यवयवेन विग्रहः समुदायः समासार्थः,
'असिद्वितीयोनुससार पाण्डवम्'
'संकर्षणद्वितीयस्य बलं कृष्णस्य वर्धताम्'
इति द्वयोर्द्विवचनमिति द्विवचनं प्राप्नोति ॥

(प्रदीपः) असिद्वितीय इति । द्वयोः पूरणो द्वितीयः । स च द्व्यात्मकस्य समुदायस्यावयवो भवतीति तदवयवस्य समुदायस्य समासेनाभिधानाद् द्विवचनप्रसङ्गः ॥

(उद्योतः) द्विवचनप्रसङ्ग इति । उद्भूतावयवभेदस्य समुदायस्य समासार्थत्वात् । तत्र बहुवचनमिवात्रापि द्विवचनं स्यादिति भावः ॥

(पश्चात्प्रोक्तविग्रहाभ्युपगमभाष्यम्)

अस्तु तर्ह्ययमेव विग्रहः—अर्धं तृतीयमनयोरिति ॥

(आक्षेपस्मारणभाष्यम्)

ननु चोक्तम्—षष्ठ्यर्थो नोपपद्यत इति ॥

(समाधानभाष्यम्)

नैष दोषः । इदं तावदयं प्रष्टव्यः—अथेह 'देवदत्तस्य भ्राता' इति कः षष्ठ्यर्थ इति?। तत्रैतत्स्यात्—एकस्मात्प्रादुर्भाव इति । एतच्च वार्तम् । तद्यथा—सार्थिकानामेकप्रतिश्रये उषितानां प्रातरुत्थाय प्रतिष्ठमानानां न कश्चित्परस्परमभिसंबन्धो भवति ।

एवंजातीयकं भ्रातृत्वं नाम॥ अत्र चेद्युक्तः षष्ठ्यर्थो दृश्यते, इहापि युक्तो दृश्यताम्॥

(प्रदीपः) **अथेति**। नह्यत्र स्वस्वामिभावादिः संबन्धोऽस्तीति भावः॥ **एतच्च वार्तमिति**। असारवाची वार्तशब्दः। मातापितृभ्यामेव पुत्रयोर्जन्यजनकभावः संबन्धो न तु परस्परेण कश्चिदित्यर्थः॥ **अत्र चेदिति**। परस्परोपकाराभावेपि यदि समानोदरशायित्वमात्रेण काल्पनिकः संबन्धस्तदार्धस्य द्वाभ्यामेकप्रदेशावस्थानादिनिमित्तः संवन्धो युक्त इत्यर्थः॥

(उद्योतः) **स्वस्वामीति**। साक्षात्संबन्धोपलक्षणम्। कचिद्वार्तशब्दस्य युक्तपर्यायत्वदर्शनादाह—**असारेति**। अनेकार्थोयमिति भावः॥ **अवस्थानादिनिमित्त इति**। सर्वत्र संबन्धस्य क्रियाकारकभावपूर्वकत्वमिति उभयत्रापि काल्पनिकोऽवयवावयविभावो व्यवहारनियामक इति भावः। यद्वा सम्बन्धत्वेन सम्बन्धोऽसत्रपि विकल्पात्मकज्ञानविषयः पुरुषस्य चैतन्यमितिवत्षष्ठीप्रयोगनिमित्तमिति भावः॥

(आक्षेपभाष्यम्)

इह तर्हि अर्धतृतीया आनीयन्तामित्युक्ते अर्धस्यानयनं न प्राप्नोति॥

(प्रदीपः) **इह तर्हीति**। अर्धं तृतीयमनयोरिति द्वयोरेव समासार्थत्वादानयनं स्याद् नार्धस्येत्यर्थः॥

(उद्योतः) **नार्धस्येति**। एवं च द्विवचनप्रसङ्गोपि नोदित इति बोध्यम्॥

(प्रथमप्रोक्तविग्रहाभ्युपगमभाष्यम्)

अस्तु तर्ह्ययमेव विग्रहः—अर्धं तृतीयमेषामिति॥

(आक्षेपस्मारणभाष्यम्)

ननु चोक्तम्—
'असिद्वितीयोनुससार पाण्डवम्'
'संकर्षणद्वितीयस्य बलं कृष्णस्य वर्द्धताम्'
इति द्वयोर्द्विवचनमिति द्विवचनं प्राप्नोतीति॥

(समाधानभाष्यम्)

नैष दोषः। अयं तीयान्तः शब्दोस्त्येव पूरणे वर्तते। अस्ति सहायवाची। तद्यः सहायवाची तस्येदं ग्रहणम्—'असिद्वितीयः' असिसहाय इति गम्यते॥

(प्रदीपः) **अस्ति सहायवाचीति**। अव्युत्पन्न एवेत्यर्थः॥

(उद्योतः) भाष्ये—**असिसहायेति**। एवं चैकस्यैवान्यपदार्थत्वं न तु अवयवसमुदायस्येति भावः॥

(आक्षेपभाष्यम्)

एवमपि—अर्धतृतीया इत्येकस्मिन्नेकवचनं प्राप्नोति। एकार्था हि समुदाया भवन्ति। यथा—शतं यूथं वनमिति॥

(पश्चात्प्रोक्तविग्रहाभ्युपगमभाष्यम्)

अस्तु तर्ह्ययमेव विग्रहः—अर्धं तृतीयमनयोरिति॥

(आक्षेपस्मारणभाष्यम्)

ननु चोक्तम्—अर्धतृतीया आनीयन्तामित्युक्ते अर्धस्यानयनं न प्राप्नोतीति॥

(समाधानभाष्यम्)

नैष दोषः। भवति बहुव्रीहौ तद्गुणसंविज्ञानमपि। तद्यथा—शुक्लवाससमानय लोहितोष्णीषा ऋत्विजः प्रचरन्तीति तद्गुण आनीयते तद्गुणाश्च प्रचरन्ति॥

(प्रदीपः) **भवति बहुव्रीहाविति**। उपलक्षणार्थसहितयोर्द्वयोरानयनं भविष्यतीत्यर्थः। संयोगसमवायलक्षणे संबन्धे यदा बहुव्रीहिस्तदा तद्गुणसंविज्ञानं भवति शुक्लवासा लम्बकर्ण इति। स्वस्वामिभावादिके तु संबन्धे बहुव्रीहौ तद्गुणसंविज्ञानाभावो यथा चित्रगुरिति संक्षेपेण विषयभागः॥

(उद्योतः) **संयोगसमवायेति**। एवं च प्रकृते तद्गुणसंविज्ञानस्य वक्तुमशक्यत्वाल्लोहितोष्णीषमानय इत्यादौ उपलक्षणार्थसाहित्यप्रयुक्तवचनादर्शनेन द्विवचनप्रसङ्गाच्च दुष्टोयं पक्ष इति भावः॥

(प्रथमप्रोक्तविग्रहाभ्युपगमभाष्यम्)

अथ वा पुनरस्त्वयमेव विग्रहः—अर्धं तृतीयमेषामिति॥

(प्रदीपः) द्विवचनप्रसङ्गाद् दुष्टोयं पक्ष इति मत्वाह—**अथ वेति**॥

(आक्षेपस्मारणभाष्यम्)

ननु चोक्तम्—एकवचनं प्राप्नोतीति॥

(समाधानभाष्यम्)

नैष दोषः। संख्या नामेयं परप्रधाना। संख्येयमनया विशेष्यम्। यदि चात्रैकवचनं स्यात् संख्येयमविशेषितं स्यात्॥

(प्रदीपः) **संख्या नामेयमिति**। अयमर्थः—अर्धं तृतीयमेषामिति बहुत्वसंख्याविशिष्टोन्यपदार्थो वाक्य उपात्त इति तथाभूतस्यैव समासो वाचक इति अवश्यप्रत्याय्यं बहुत्वम्। यथा च वृक्षा इति बहुत्वसंख्यायुक्तः समुदायः प्रतीयते धवखदिरपलाशा इति च, तथार्धतृतीया इत्यपीत्यर्थः॥

(उद्योतः) **अयमर्थ इति**। प्राग्व्याख्यात एतद्भाष्याक्षरार्थः। एवं च विग्रह उद्भूतावयवभेदस्य समुदायस्य अन्यपदार्थत्वात्तादृश एव समासशक्य इति तत्प्रत्यायनाय बहुवचनमेवेति तात्पर्यम्॥

(आक्षेपभाष्यम्)

इह तर्ह्यर्धतृतीया द्रोणा इत्ययं द्रोणशब्दः समुदाये प्रवृत्तः अवयवे नोपपद्यते ॥

(प्रदीपः) इह तर्हीति। अर्धस्य द्रयोश्च द्रोणयोर्यः समुदायः स समासार्थस्तत्रार्धस्य द्रोणत्वाभावाद् द्रोणा इति नोपपद्यत इत्यर्थः ॥

(समाधानभाष्यम्)

नैष दोषः। समुदायेषु हि प्रवृत्ताः शब्दाः अवयवेष्वपि वर्तन्ते। तद्यथा—पूर्वे पञ्चालाः, उत्तरे पञ्चालाः, तैलं भुक्तं, घृतं भुक्तं, शुक्लो नीलः कपिल इति। एवमयं समुदाये द्रोणशब्दः प्रवृत्तोऽवयवेष्वपि वर्तते ॥

(प्रदीपः) नैष दोष इति। अर्धेपि द्रोणत्वोपचाराद् द्रोणशब्दस्य प्रवृत्तिरित्यर्थः ॥

(आक्षेपभाष्यम्)

कामं तर्ह्यनेनैव हेतुना यदा द्वौ द्रोणौ अर्धाढकं च तदा कर्तव्यमर्धतृतीया द्रोणा इति ॥

(उद्योतः) भाष्ये—कर्तव्यमर्धतृतीया इति। प्रयोक्तव्यमित्यर्थः ॥

(समाधानभाष्यम्)

न कर्तव्यम्। समुदायेषु वृत्ताः शब्दाः केष्ववयवेषु वर्तन्ते?, योवयवस्तं समुदायं न व्यभिचरति। कं च समुदायं न व्यभिचरति?। अर्धद्रोणो द्रोणम्। अर्धाढकं पुनर्व्यभिचरति ॥ अनेक ॥ २४॥

(प्रदीपः) न कर्तव्यमिति। स्वावयव एव समुदायरूपोपचारो नान्यदीये अवयव इत्यर्थः ॥ अर्धद्रोणो द्रोणमिति। द्रोणेन विनास्याभावादित्यर्थः ॥ अर्धाढकमिति। चतुराढको द्रोणः। ततश्च विनापि द्रोणेनैकाढकसद्भावेप्यर्धस्य भावः ॥ २४ ॥

(उद्योतः) भाष्ये—योऽवयवस्तं समुदायं न व्यभिचरतीति। यदवयवबुद्धिस्तद्बुद्धिं न व्यभिचरतीत्यर्थः। अन्यथा द्रोणाभाववद्वृत्तित्वरूपो व्यभिचारोर्धद्रोणेप्यस्त्येवेति तदसंगतिः स्पष्टैव ॥ अर्धाढकं पुनर्व्यभिचरतीत्यस्य द्रोणमिति शेषः। अर्धाढकं कर्तृ ॥ द्रोणेन विनेति। द्रोणबुद्ध्या विनेत्यर्थः ॥ द्रोणेन। द्रोणबुद्ध्या ॥ एकाढकसद्भावे तद्बुद्धिसद्भावे ॥ २४ ॥

(२८३ बहुव्रीहिसंज्ञासूत्रम् ॥ २। २। २ आ. २)

२८३ संख्ययाऽव्ययासन्नादूराधिकसंख्याः संख्येये ॥ २।२।२५ ॥

(द्वित्रादिशब्दार्थाधिकरणम्)

(आक्षेपभाष्यम्)

द्वित्राः त्रिचतुरा इति कोयं समासः? ॥

(प्रदीपः) संख्यया ॥ २५ ॥ द्वित्रा इति। बहुव्रीहिनिमित्तस्य डचो दर्शनादात्त्वाभावाच्च निश्चिते बहुव्रीहित्वे विग्रहनिश्चयाय प्रश्नः—**कोयं समास इति ॥**

(उद्योतः) संख्यया—॥ २५ ॥ आत्त्वाभावाच्चेति। अष्टन इत्यात्त्वस्य बहुव्रीहौ निषेधात्सोपि बहुव्रीहित्वनिश्चायक इति भावः ॥ कोयमिति भाष्यस्य किंविग्रहकोयमित्यर्थ इति तात्पर्यम् ॥

(समाधानभाष्यम्)

बहुव्रीहिरित्याह ॥

(आक्षेपभाष्यम्)

कोस्य विग्रहः? ॥

(प्रदीपः) स्वाभिप्रायं प्रकाशयितुमाह—**कोस्येति।** यदि तावद् द्वौ त्रय एषामुन्मुग्धानामिति तदा मत्वर्थत्वात् पूर्वेण बहुव्रीहिः सिद्धः, समासान्तस्तु डच् न सिध्यति असंख्येयवृत्तित्वाद् बहुव्रीहेः। अथ द्वौ वा त्रयो वेति, तदा पक्षे द्विवचनप्रसङ्गः ॥

(समाधानभाष्यम्)

द्वौ वा त्रयो वेति ॥

(आक्षेपभाष्यम्)

भवेद्यदा बहूनामानयनं तदा बहुवचनमुपपन्नम्। यदा तु खलु द्वावानीयेते तदा न सिध्यति॥

(प्रदीपः) भवेद्यदेति। विकल्पो वार्थः इति द्वित्रशब्दः कदाचिद् द्वयोर्वाचकः कदाचित् त्रयाणाम् ॥

(उद्योतः) कदाचिद् द्वयोर्वाचक इति। वोपविषयत्वस्यैव विकल्पं वाशब्दो द्योतयतीत्यभिमानः ॥ बहूनामानयनमित्यस्य बहूनामानयनान्वय इत्यर्थ इति तात्पर्यम् ॥ भाष्ये—**यदा द्वावानीयेते इति।** द्वावेवानयनान्वयित्वेन बुध्येते इति भावः ॥

(समाधानभाष्यम्)

तदापि सिद्धम् ॥ कथम्?। केचित्तावदाहुः—अनिर्ज्ञातेर्थे बहुवचनं प्रयोक्तव्यमिति। तद्यथा—कति भवतः पुत्राः, कति भवतो भार्या इति ॥

अपर आह—द्वौ वेत्युक्ते त्रयो वेति गम्यते। त्रयो वेत्युक्ते द्वौ वेति गम्यते। सैषा पञ्चाधिष्ठाना वाक् तत्र युक्तं बहुवचनम् ॥

(प्रदीपः) अनिर्ज्ञातेर्थे इति। केचिद्वचनमेतदित्याहुः ॥ अन्ये तु न्यायसिद्धं मन्यन्ते। अयमर्थः—संशयोत्र वार्थो न विकल्पः। स चानियतसंख्याविमर्शीति विमर्शविषयबहुत्वसद्भावाद् बहुवचनम्। अर्थशब्देनात्र संख्यैवोच्यते संख्यायामविज्ञातायामित्यर्थः ॥ **कति भवत इति।** अन्तर्भावितपूर्वसंख्या बहुत्वसंख्या पृच्छ्यत इति बहुवचनम् ॥ **द्वौ वेति।** विरुद्धानेकविषयत्वाद्विमर्शस्य पर्यायस्थितद्वित्वत्रित्वाधारवस्तुसंकलनया पञ्चाधिष्ठानत्वमुच्यते ॥

(उद्द्योतः) अनिर्ज्ञाते इति । परस्परं प्रतिक्षेपकद्वित्वत्रित्वधन्त इति बोधेऽनिर्णीतसंख्यात्वाद्बहुवचनं भवतीति भावः । तदाह— केचिदिति । परस्परप्रतिक्षेपकत्वं हि वार्थः । कदाचिद् द्वयोर्बोधः कदाचित्त्रयाणामिति अनिर्णीतसंख्यार्थकत्वाद्वचनेन बहुवचनं साध्यमिति तदाशयः ॥ अन्ये त्विति । संशयोऽत्रेति । अनिर्ज्ञात इत्यस्य निश्चयेनाविज्ञाते इत्यर्थ इति भावः ॥ तथा च संशयविषये इति फलितम् ॥ अर्थशब्देनात्रेति । प्रकरणादिति भावः ॥ अन्तर्भावितेति । संख्यान्तो बहुव्रीहिः । अत एवैको द्वावित्यप्युत्तरम् । अन्यथा बहुविषयप्रश्ने तदुत्तरासंगतिरिति भावः ॥ विरुद्धानेकेति । विकल्पार्थ एव वाशब्दः । क्रियाविषयत्वस्यैव च विकल्पो न तु बोधविषयत्वस्यापि स इति भावः ॥ विमर्शः परस्परप्रतिक्षेपः । विकल्पे इयत्तानिर्धारणम्, संशये त्वनिर्धारणमिति भेदः। यद्वा संशय एव वार्थः ॥ अनेकविषयत्वात् । अनेकविषयरूपत्वात् ॥ विमर्शस्य संशयस्येत्यर्थः । संशयत्वं च विषयनिष्ठमित्यन्यत्र निरूपितम् ॥ पञ्चाधिष्ठानत्वमुच्यते इति । वाच इति शेषः । द्वित्रशब्दजन्यो बोधो नियमेन पञ्चविषय इति भावः ॥

(द्विदशादिशब्दार्थाधिकरणम्)

(आक्षेपभाष्यम्)

अथ द्विदशाः त्रिदशा इति कोयं समासः ? ॥

(उद्द्योतः) भाष्ये— द्विदशाइति । अत्रापि डजात्वाभावाभ्यां बहुव्रीहित्वस्य निश्चयः । द्वौ दश एषामुन्मुग्धानामिति विग्रहे डजनुपपत्तिः संख्येये समासावर्तनात् । तस्माद्विग्रहविषय एवात्रापि प्रश्नः ॥

(समाधानभाष्यम्)

बहुव्रीहिरित्याह ॥

(आक्षेपभाष्यम्)

कोस्य विग्रहः ? ॥

(समाधानभाष्यम्)

द्विर्दश द्विदशा इति ।

(प्रदीपः) द्विर्दशेति । अयं भावः— द्वौ दशेति विग्रहो विरोधान्न क्रियते । तथा हि— द्वित्वं दशसंख्याया एकत्वान्नोपपद्यते नापि संख्येयानां दशानाम् । तस्माद् द्विशब्देन दशत्वावृत्तिगता द्वित्वसंख्या प्रतिपाद्यत इति सुजन्तेन वाक्यं क्रियते ॥

(उद्द्योतः) तत्र स्वपदविग्रहपरित्यागेनास्वपदविग्रहः कस्मादित्यत आह— अयं भाव इति ॥ नापि संख्येयानामिति । तेषां बहुत्वात् ॥ दशत्वावृत्तीति । यद्यपि क्रियाभ्यावृत्तिगणने कृत्वसुच् एवं च दशत्वावृत्तीत्यसंगतम्, तथाप्यावृत्तिक्रियाजन्यगणनमेवात्रेति बोध्यम् ॥ दशत्वावृत्तीत्यस्य दशत्वावृत्तिजन्यगतेत्यर्थः ॥

(१३९८ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ संख्यासमासे सुजन्तत्वात्संख्याप्रसिद्धिः ॥ * ॥

(भाष्यम्) **संख्यासमासे सुजन्तत्वात्संख्येयाप्रसिद्धिः । नहि सुजन्ता संख्यास्ति ॥**

द्वि० ५८

(प्रदीपः) अत्र दूषणमाह— संख्यासमास इति सुजन्तस्य शब्दान्तरत्वात् संख्यावाचित्वं नास्तीत्यर्थः ॥

(उद्द्योतः) यद्यपि सुजन्तोप्यावृत्तिगतसंख्याबोधकः, तथापि संख्यायाः संख्येयस्य वा प्राधान्येन बोधकः संख्याशब्द उच्यते । नायं तथा द्वित्वसंख्यावृत्तिकदशसंवन्त इति प्रतीतेरित्याह— सुजन्तस्येति ॥ शब्दान्तरत्वात् । संख्यासंख्येयातिरिक्तबोधकत्वात् ॥

(समाधानभाष्यम्)

एवं तर्ह्येवं विग्रहः करिष्यते— द्वौ दशतौ द्विदशा इति ॥

(प्रदीपः) द्वौ दशताविति । द्वौ दशतौ वर्गावित्यर्थः॥

(उद्द्योतः) वर्गाविति । पञ्चद्दशतौ वर्गे वेति निपातनात् वर्गगतद्वित्वप्रतिपादकतया द्विशब्दः संख्यावाचीत्यर्थः ॥

(आक्षेपभाष्यम्)

एवमपि अत्कारान्तत्वात्संख्येयेत्यप्रसिद्धिः । न ह्यत्कारान्ता संख्यास्ति ॥

(प्रथमप्रोक्तविग्रहाभ्युपगमभाष्यम्)

अस्तु तर्ह्ययमेव विग्रहः— द्विर्दश द्विदशा इति ॥

(आक्षेपकारणभाष्यम्)

ननु चोक्तम्— *संख्यासमासे सुजन्तत्वात्संख्येयाप्रसिद्धिरिति ॥

(१३९९ आक्षेपबाधकवार्तिकम् ॥ २ ॥)

॥ * ॥ नवाऽसुजन्तत्वात् ॥ * ॥

(भाष्यम्) **न वा एष दोषः । किं कारणम्? । असुजन्तत्वात् । सुजन्तत्वादित्युच्यते । न चात्र सुजन्तं पश्यामः ॥**

(प्रदीपः) न वेति । नहि वाक्योपमर्देनेन समासः क्रियते लौकिके प्रयोगे द्वयोरपि नित्यत्वात् । अन्वाख्यानमात्रं तु शास्त्रेण क्रियते । तत्र वृत्तिविषये सुचमन्तरेणाभ्यावृत्तिसंख्याभिधायी द्विशब्द इति संख्यावाचित्वात्समासो भवत्येव ॥ न चात्रेति । वृत्तावित्यर्थः ॥

(उद्द्योतः) अभ्यावृत्तिसंख्याभिधायीति । आवृत्तिजन्यगतसंख्याभिधायीत्यर्थः ॥ आवृत्तिश्च समासशक्येति द्विशब्दस्तद्गतसंख्यायामेव वर्तत इति भावः । भाष्ये— सुजन्तत्वादित्युच्यते इति । त्वया सुजन्तत्वात्संख्येयाप्रसिद्धिरित्युच्यते । न च वृत्तौ सुजन्तमस्ति तस्मात्केवलेनैव समासः स चासुजन्त इति संख्येति प्रसिद्धिरित्यर्थः ॥

(आक्षेपभाष्यम्)

किं पुनः कारणं वाक्ये सुज् दृश्यते, समासे न दृश्यते ? ॥

(१४०० समाधानवार्तिकम् ॥ ३ ॥)

॥ * ॥ सुजभावोभिहितार्थत्वात् समासे ॥ * ॥

(भाष्यम्) समासे सुजभावः ॥ किं कारणम्?। अभिहितार्थत्वात् । अभिहितः सुजर्थः समासेनेति कृत्वा समासे सुज् न भविष्यति ॥

(प्रदीपः) अभिहित इति । शब्दशक्तिस्वाभाव्यात्समासः सुजर्थं प्रत्याययतीत्यर्थः ॥

(उद्द्योतः) सुजर्थमिति । यदुत्पत्तिगणने द्विशब्दस्तामुत्पत्तिविशिष्टां क्रियामित्यर्थः ॥

(प्रत्याक्षेपभाष्यम्)

किं च भोः 'सुजर्थे' इति समास उच्यते?॥

(प्रदीपः) इतरः कार्यशब्ददर्शनमाश्रित्याह—किञ्च भो इति । यथा चार्थे द्वन्द्वस्य विधानाद् द्वन्द्वे चशब्दो न प्रयुज्यते तथा यद्ययं समासः सुजर्थे विधीयेत तदा सुचोऽप्रयोगः स्याद् नान्यथेति प्रश्नः ॥

(समाधानभाष्यम्)

न खलु सुजर्थे इत्युच्यते गम्यते तु सुजर्थः । कथम्?। यावता संख्येयो यः संख्यया संख्यायते । स च क्रियाभ्यावृत्त्यर्थः । स चोक्तः समासेनेति कृत्वा समासे सुज् न भविष्यति ॥

(प्रदीपः) न खल्विति । नहि शब्दैरर्थाभिधानं वाचनिकं किन्तु स्वाभाविकम् ॥ स चेति । क्रियाभ्यावृत्तिलक्षणोर्थः संख्येयो, न तु दशसंख्या, नापि तत्संख्यायुक्ताः । एतच्च पूर्वमुक्तम् । वाक्ये तु सुचमन्तरेण क्रियाभ्यावृत्तेरनवगमात् सुच्प्रयोगः । ततश्चास्वपदविग्रहः क्रियते द्विर्दश द्विदशा इति । अनेनैव न्यायेन द्वौ दशताविल्यपि विग्रहः । कार्यः न्यायसाम्यात्तु प्रतीयमानत्वाद् भाष्यकारेण पुनर्न दर्शितः । तदुक्तम्—

शब्दान्तरत्वाद् वाक्येषु विशेषा यद्यपि श्रुताः ।
वृत्तिशब्दोन्य एवायमर्थान्तरनिबन्धनः ॥

इति ॥

(उद्द्योतः) नहि शब्दैरिति । तत्रतत्रार्थविशेषोपादानमबुधबोधनायान्वाख्याननिमित्तत्वेनाश्रीयते नतु शक्त्याधानाय । न ह्येतावता सर्वत्र तदुपादानमावश्यकमिति भावः ॥ भाष्ये समासेन तत्प्रतीतौ बीजमाह—यावता संख्येयो यः संख्ययेति । संख्येयत्वयोग्यो यः संख्यया संख्यायते गण्यते । संख्येयश्च पूर्वपदार्थसंख्यायाः प्रकृतेनोत्तरपदार्थः स च संख्यारूपः संख्येयरूपो वा उभयथापि न द्व्यादिसंख्येयः आद्यस्यैकत्वाद् द्वितीयस्य दशत्ववत्त्वात् । अतः सामर्थ्यात् क्रियाजन्नरूपः सोर्थो वाच्य इति सामर्थ्यादेव स समासेनोक्त इति भावः । तद् ध्वनयन् व्याचष्टे—क्रियाभ्यावृत्तीति । भाष्ये स च क्रियाभ्यावृत्त्यर्थ इति कर्मधारयः । संख्येयश्च क्रियाजन्मरूपोर्थः ॥ स चोक्त इति । क्रिया तज्जन्मरूपोर्थश्च समासेनोक्त इत्यर्थः । अनेन पञ्चकृत्वः पचतीत्यादौ क्रियोत्पत्तिः सुजाद्यर्थ इति बोधितं । अत्रोक्तत्वादिति वदतास्यैकार्थीभावकृतत्वं नेति सूचयति । अपृथगुपस्थितिर्हि सः, न तत्कृतत्वमस्य । एवमन्यपदार्थादवोपि न तत्कृता इति बोध्यम् ॥ नन्वनया युक्त्या वाक्येपि सुच्प्रयोगो न स्यादत आह—वाक्येत्विति । शब्दशक्तिस्वाभाव्यादिति भावः ॥ अनेनैवेति । वृत्तौ दशशब्दो दशदर्थकः सामर्थ्यात् । उद्भूतावयवभेदो वर्ग एव समासार्थ इति नित्यबहुवचनान्तत्वमिति भावः ॥

(प्रत्याख्यानाधिकरणम्)

(१४०१ प्रत्याख्यानवार्तिकम् ॥ ४ ॥)

॥ * ॥ अशिष्यः संख्योत्तरपदः संख्येयवाभिधायित्वात् ॥ * ॥

(भाष्यम्) अशिष्यः संख्योत्तरपदो बहुव्रीहिः ॥ किं कारणम्?। संख्येयवाभिधायित्वात् । संख्येयं वार्थश्चाभिधीयते तत्रान्यपदार्थ इत्येव सिद्धम् ॥

(प्रदीपः) संख्येयमिति । अधिका विंशतिर्यासां ता अधिकविंशा गाव इति संख्यानवृत्तित्वाद्विंशतिशब्दस्य संख्येयमन्यपदार्थ उपपद्यत इति भावः ॥

(उद्द्योतः) अधिकाविंशतिर्यासामिति । किंचिदधिका विंशतिः संख्या यासामित्यर्थः ॥ भाष्ये—वार्थश्चेति । सुजर्थस्तु न विशेष्य इति स नोक्तः ॥ संख्यानेति । द्वौ दशतौ विंशतिरिति द्वौ दशतौ परिमाणमस्य विंशतिरित्युभयथा तद्व्युत्पत्तेरिति भावः ॥ संख्येयवाभिधायित्वादिति । द्विदशा इत्यादावपि द्विरावृत्तदशत्वसंख्यावन्त इत्यर्थात्संख्येयमेवान्यपदार्थ इति भावः ॥

(प्रत्याख्याननिराकरणभाष्यम्)

भवेत्सिद्धमधिकविंशाः अधिकत्रिंशा इति, यत्रैतद्विचार्यते विंशत्यादयो दशदर्थे वा स्युः परिमाणिनि वेति । इदं तु न सिध्यति—अधिकदशा इति, यत्र नियोगतः संख्या संख्येये एव वर्तते ॥

(प्रदीपः) दशदर्थ इति । संख्याने संख्येये वेत्यर्थः । अधिकदशा इति । दशशब्देन संख्येयस्याभिधानादन्यपदार्थाभावः । तस्माद्दशाद्यर्थं सूत्रं कर्तव्यमेव ॥

(उद्द्योतः) द्वित्रा इत्यत्रापि द्वित्र्यन्यतरा इति बोधेऽर्थस्य प्राधान्यम् ॥ अधिकविंशा इत्यादौ सर्वनामसंख्ययोरिति विंशतिशब्दस्य पूर्वनिपातः स्यादिति न शङ्क्यं तत्प्रकरणस्यानित्यत्वात् ॥ तत्र द्वित्रा इत्यत्र वार्थोन्यपदार्थः । अधिकविंशा इत्यादौ च संख्येयमिति सर्वत्रान्यपदार्थ इत्येवं सिद्धम् । डजपि संख्येये वर्तमानबहुव्रीहेरित्यर्थेन सिद्धः । अतिप्रसङ्गस्त्वनभिधानान्नेत्याशयेन पूर्वपक्षे विंशत्यादीनां संख्यासंख्येयोभयपरतया सिद्धावपि दशादीनां संख्येयमात्रपरतया अधिकदशा इत्यादि पूर्वेण न सिध्यतीत्याह—

भाष्ये—भवेत्सिद्धमित्यादि ॥ यद्यपि बहुषु बहुवचनमिति सूत्रे एकद्विबहुशब्दानां संख्यासंख्येयोभयपरता भाष्ये उक्ता, तथापि सौत्रप्रयोगविषयमेव तदिति बोध्यम् ॥

(उपदशादिशब्दार्थाधिकरणम्)

(आक्षेपभाष्यम्)

अथोपदशा इति कोयं समासः? ॥

(प्रदीपः) इदानीमव्ययं निरूप्यते बहुव्रीह्यव्ययीभावयोर्विषयविभागप्रदर्शनार्थम् ॥

(समाधानभाष्यम्)

बहुव्रीहिरित्याह ॥

(आक्षेपभाष्यम्)

कोस्य विग्रहः? ॥

(समाधानभाष्यम्)

दशानां समीपे उपदशा इति ॥

(प्रदीपः) **उपदशा इति ॥ दशानां समीप इति** सप्तम्या समीपिप्राधान्ये बहुव्रीहिः, समीपप्राधान्ये त्वव्ययीभाव इति प्रदर्शितं भवति ॥

(उद्योतः) **सप्तम्येति** । तथा च सन्तीति क्रियाक्षेपाद् ये समीपे सन्ति ते लभ्यन्ते । अन्यथा प्रथमान्तमेव पठेदित्यर्थः । एवं च पूर्वपदार्थप्रधानोयमिति पूर्वेण न सिद्धिरिति भावः ॥

(आक्षेपभाष्यम्)

कस्य पुनः सामीप्यमर्थः? ॥

(प्रदीपः) **सामीप्यमिति** । धर्मेण धर्मी लक्ष्यते कस्य सामीप्यवानर्थ इत्यर्थः । उपशब्दो हि समीपमात्रवाच्युपकुम्भादिषु दृष्ट इति तस्य समीपिवाचित्वं नास्ति, नापि दशाशब्दस्य । समासस्येति चेत्तदाऽस्येवान्यपदार्थवृत्तित्वमिति प्रश्नः ॥

(उद्योतः) समासस्य समीपिप्रधानताया उक्तत्वेन **कस्य सामीप्यमर्थ** इति अयुक्तमित्यत आह—**धर्मेणेति** । समीपिशब्दाद् ब्राह्मणादित्वात्ष्यञित्याशयः ॥

(समाधानभाष्यम्)

उपस्य ॥

(प्रदीपः) **उपस्येति** । आराच्छब्दवदनेकार्थत्वादुपशब्दस्य समीपवानर्थः ॥

(उद्योतः) **आराच्छब्दवदिति** । अनेकार्थत्वमात्रे दृष्टान्तः ॥ अत्र निपातस्याप्युपस्य वाचकत्वं द्रष्टव्यम् । अतएव तदर्थस्य विशेष्यतया भानम् ॥

(आक्षेपभाष्यम्)

यद्येवं, नान्यपदार्थो भवति ॥

(प्रदीपः) स एवाह—**यद्येवमिति** । यदोपशब्दस्यैवासावर्थ इत्यर्थः ॥

(प्रत्याख्यानभाष्यम्)

तत्र च प्रथमानिर्दिष्टं संख्याग्रहणं शक्यमकर्तुम् ॥

(प्रदीपः) एवमव्ययासन्नादूराधिकग्रहणं स्थापितम् । संख्याग्रहणं तु न कर्तव्यम्, द्वित्रा इत्यादौ वार्थस्यान्यपदार्थत्वादित्याह—**तत्रेति** ॥

(उद्योतः) **वार्थस्येति** । संख्येयस्योपलक्षणमेतत् ॥

(१४०२ संख्याग्रहणस्थापनवार्तिकम् ॥ ५ ॥)

॥ * ॥ मत्वर्थे वा पूर्वस्य विधानात् ॥ * ॥

(भाष्यम्) **अथ वा मत्वर्थे पूर्वो योगः । अमत्वर्थार्थोयमारम्भः ॥**

(प्रदीपः) इदानीमेतदपि स्थापयन्नाह—**अथवेति** ॥

(उद्योतः) अधिकदशा इत्याद्यर्थं तदिति भाष्यकृतोक्तम् ॥ इदानीं वार्तिककार आह—**मत्वर्थे इति** ॥ एवं च पदानामसामानाधिकरण्याद् द्वित्रा द्विदशा इत्याद्यसिद्धिरिति भावः । द्वित्रान्पश्येत्यादौ परिनिष्ठितविभक्त्या समासे शेषग्रहणबोधितप्रथमान्तत्वाभाव इत्यपि बोध्यम् ॥

(१४०३ प्रत्याख्याननिराकरणवार्तिकम् ॥ ६ ॥)

॥ * ॥ कबभावार्थं वा ॥ * ॥

(भाष्यम्) **अथ वा कब् मा भूदिति ॥ संख्ययाऽव्य ॥ २५ ॥**

(प्रदीपः) ननु मत्वर्थग्रहणं तत्र न करिष्यते द्वित्रा इति सिद्धय इत्याह—**कबभावार्थं वेति** । **शेषाद्विभाषेत्यत्र** शेषाधिकारविहितो बहुव्रीहिर्गृह्यते, **अनेकमन्यपदार्थ** इत्यत्रैव च शेषग्रहणमनुवर्तते, नोत्तरेषु योगेषु ॥ २५ ॥

(उद्योतः) **कबभावार्थं वेति** । अनन्तरबहुव्रीह्यधिकारापेक्षानुक्तसमासान्तत्वरूपशेषत्वस्यैव भाष्ये वक्ष्यमाणत्वादिति भावः। अनेन समासे तु शेषाधिकारस्थसमासाभावान्नेति तात्पर्यम् ॥ **शेषाधिकारेति** । न च समानाधिकरणानामित्यादिवार्त्तिकप्रत्याख्यानरीत्या शेषग्रहणमपि प्रत्याख्यातमेव । स्पष्टं चाकडारसूत्रादावुक्तं तत्कथमेतदर्थलाभ इति वाच्यम् । अनभिधानस्य दुर्ज्ञेयतया तदर्थमेतदर्थं च शेषग्रहणमावश्यकमित्याशयात् । प्रत्याख्यानं च प्रौढ्या । अनभिधानमगतिकगतिरिति तत्सूत्रे उक्तत्वात् ॥ २५ ॥

(२८४ बहुव्रीहिसंज्ञासूत्रम् ॥ २।२।२ आ. ३)

४४६ दिङ्नामान्यन्तराले ॥ २।२।२६ ॥

(२८५ बहुव्रीहिसंज्ञासूत्रम् ॥ २।२।२ आ. ४)

४४७ तेन सहेति तुल्ययोगे ॥ २।२।२७ ॥

(प्रत्याख्यानाधिकरणम्)

(१४०४ प्रत्याख्यानवार्तिकम् ॥ १ ॥)

॥ * ॥ दिक्समाससहयोगयोश्चान्तरालप्रधानाभिधानात् ॥ * ॥

(भाष्यम्) **दिक्समाससहयोगयोश्चाशिष्यो बहुव्रीहिः ॥ किं कारणम्? । अन्तरालप्रधानाभि-**

भावात् । दिक्समासे सहयोगे चान्तरालं प्रधानं चाभिधीयते तत्रान्यपदार्थ इत्येव सिद्धम् ॥

(प्रदीपः) **दिङ्नामानि ॥ २६ ॥** तुल्यन्यायत्वाद्योगद्वयस्य सहविचारः ॥ **दिक्समाससहयोगयोरिति** । अशिष्य इति पूर्ववार्तिकोक्तमपेक्ष्यते ॥ दक्षिणस्याश्च पूर्वस्याश्च दिशो यदन्तरालं दिक्सा दक्षिणपूर्वेत्युच्यते तत्रान्तरालस्यान्यपदार्थत्वात् पूर्वेणैव सिद्धः समासः । सपुत्र इत्यस्यापि समासस्य पिता प्रधानमन्यपदार्थोऽभिधेय इति नार्थः सूत्रद्वयेनेत्यर्थः ॥

(उद्द्योतः) **दिङ्नामा ॥ २६ ॥ तत्र तेनेदमिति** मध्यपतितसूत्रमतिक्रम्य योगद्वयस्य सह विचारे कारणमाह—**तुल्यन्यायत्वादिति** ॥ भाष्ये—**सहयोगयोरिति** । सहेन योगोऽस्येति विग्रहेण सपुत्र इति समास उच्यते ॥ **तत्रान्यपदार्थ इत्येवेति** । सहशब्दस्य साहित्यमेवार्थस्तद्वान्पित्रादिस्तु समासार्थ इति भावः ॥ **समानाधिकरणानामित्यस्य शेष** इत्यस्य चापरामर्शेनेदम् । अत एव वक्ष्यति—* मत्वर्थे वा पूर्वस्य * इति ॥

(आक्षेपभाष्यम्)

यद्येवं दक्षिणपूर्वा दिक् समानाधिकरणलक्षणः पुंवद्भावो न प्राप्नोति ॥

(समाधानभाष्यम्)

अद्य पुनरियं सैव दक्षिणा सैव पूर्वेति कृत्वा समानाधिकरणलक्षणः पुंवद्भावः सिद्धो भवति ॥

(प्रदीपः) **अद्य पुनरिति** । सूत्रारम्भविशिष्टे काले इत्यर्थः । तत्रारब्धेऽयमर्थो व्याख्यायते—अन्तराले यानि दिङ्नामानि वर्तन्ते तानि समस्यन्ते । दक्षिणादीनां च सामीप्यादन्तरालवृत्तित्वम् । ततश्च दक्षिणा चासौ पूर्वेति सामानाधिकरण्यात् पुंवद्भावः सिध्यति । सूत्रे त्वनारब्धेऽन्यपदार्थसंपादनाय दक्षिणपूर्वाशब्दयोः स्वार्थ एव वृत्तिरुपगन्तव्या ततो वैयधिकरण्यम् ॥ ननु सामानाधिकरण्येऽपि विशेषणसमासः सिध्यतीति नारब्धव्यमिदम् । नैतदस्ति । पूर्वपदप्रकृतिस्वरार्थं **विभाषा दिक्समास** इति विकल्पितसर्वनामसंज्ञार्थं च बहुव्रीहिसंज्ञैवेष्टव्या ॥

(उद्द्योतः) **नारब्धव्यमिति** । कर्मधारयेणैव पुंवत्त्वमपि सिध्यतीति भावः ॥ **बहुव्रीहिसंज्ञैवेति** । द्वन्द्ववारणार्थं बहुव्रीह्यावित्यावश्यकम् । तत्र एतदभावे प्रतिपदोक्तस्याभावात् प्रतिपदोक्तत्वाभेमेव वा इदं कार्यमित्याशयः ॥

(समाधानबाधकभाष्यम्)

न सिध्यति । भाषितपुंस्कस्य पुंवद्भावः । न चैतौ भाषितपुंस्कौ ॥

(प्रदीपः) **न सिध्यतीति** । नहि सामानाधिकरण्यमात्रप्रतिबद्धः पुंवद्भावः किं तु भाषितपुंस्कत्वनिबन्धनोऽपि । समानायां चाकृतौ यद्भाषितपुंस्कं तस्य पुंवद्भावः । भाषितपुंस्कशब्दस्य ह्यर्थः प्रवृत्तिनिमित्तलक्षणोऽन्यपदार्थोऽभिधेयो न शब्दः ॥

(उद्द्योतः) **प्रवृत्तिनिमित्तलक्षण इति** । भाषितः पुमान्यस्मिन्नर्थे इति व्युत्पत्तेरिति भावः ॥ **नशब्द इति** । तत्र ह्यन्यपदार्थे यत्किञ्चिदर्थमादाय स्यादेव भाषितपुंस्कत्वमिति भावः ॥

(समाधानसाधकभाष्यम्)

ननु च भोः दक्षिणशब्दः पूर्वशब्दश्च पुंसि भाष्येते ॥

(समाधानबाधकभाष्यम्)

समानायामाकृतौ यद्भाषितपुंस्कम् । आकृत्यन्तरे चैतौ भाषितपुंस्कौ । दक्षिणा पूर्वेति दिक्शब्दौ । दक्षिणः पूर्व इति व्यवस्थाशब्दौ ॥

(प्रदीपः) **दिक्शब्दाविति** । विना प्रवृत्तिनिमित्तेन दिग्विशेषे रूढ्या प्रवृत्तावित्यर्थः ॥

(उद्द्योतः) **विना प्रवृत्तिनिमित्तेनेति** । शब्दातिरिक्तप्रवृत्तिनिमित्तेनेत्यर्थः । यदा व्यक्तिमात्रबोधस्ततो रूढ्येति दक्षिणादिशब्द एव तत्र प्रवृत्तिनिमित्तं तदभाव एव वा न तु व्यवस्थाविषयं प्रवृत्तिनिमित्तमित्यर्थः ॥ **व्यवस्थाशब्दाविति** भाष्यस्यापि व्यवस्थाविषयप्रवृत्तिनिमित्तकावित्यर्थः । नहि स्वाभिधेयापेक्षावधिनियमरूपव्यवस्था कस्यापि प्रवृत्तिनिमित्तं न भवति ॥

(आक्षेपभाष्यम्)

यदि पुनर्दिक्शब्दा अपि व्यवस्थाशब्दाः स्युः । कथं यानि दिगुपदिष्टानि कार्याणि ? ॥

(प्रदीपः) **यदि पुनरिति** । ततश्च व्यवस्थाकृतौ समानायां भाषितपुंस्कत्वस्योपपत्तिः ॥ **कथं यानीति** । यदि प्रवृत्तिनिमित्ताश्रयेण दिशि वर्तन्ते न तु रूढ्या तदा दिक्शब्दत्वानुपपत्तिः ॥

(उद्द्योतः) दिक्शब्दानां सर्वनामत्वमवश्यमेवेष्टव्यमिति तात्पर्यकस्य **यदि पुनर्दिक्शब्दा अपि व्यवस्थाशब्दाः स्युरिति** भाष्यस्य **स्यात्तर्हि भाषितपुंस्कत्वमिति** शेषः । दिग्वाचकपूर्वादीनां पृथ्वीमध्यभागावधिकोदयाचलादिपर्यन्तदेशरूपोपाधिविशिष्टदिशि प्रवृत्तिरिति भावः ॥ **व्यवस्थाकृताविति** । व्यवस्थाविषयप्रवृत्तिनिमित्ते समाने इत्यर्थः ॥ **नतु रूढ्येति** । शब्दातिरिक्तप्रवृत्तिनिमित्तनिरपेक्षरूढ्येत्यर्थः । प्रवृत्तिनिमित्तविशेषानपेक्षदिग्रूढशब्दत्वं हि तत्त्वमिति भावः ॥

(समाधानभाष्यम्)

यदा दिशो व्यवस्थां वक्ष्यन्ति ॥

(प्रदीपः) यदा दिश इति । विषयवशात्प्रवृत्तिनिमित्ताश्रयायामपि प्रवृत्तौ दिक्शब्दत्वं पूर्वादीनां संभवतीत्यर्थः ॥

(उद्द्योतः) विषयवशादिति । दिगादिरूपविषयवशादित्यर्थः । अस्य दिक्शब्दत्वमित्यनेनान्वयः ॥ भाष्ये—यदा दिश इति । यदा दिग्वृत्तिव्यवस्थाविषयप्रवृत्तिनिमित्तं वक्ष्यन्तीत्यर्थः ॥ आकाशवदेकस्यैव दिक्पदार्थस्यौपाधिको भेदः । उपाधिश्च पृथिवीमध्यं तत्प्रान्तस्थाश्चत्वारः पर्वताः । एवं च तत्राप्युदयाचलसंनिहितत्वादिकमेव प्रवृत्तिनिमित्तम् । अवधिस्तु परं पृथ्वीमध्यमेव । एवं च पुंवत्त्वं सिद्धम् । दिक्शब्दत्वं च विशेष्यतया दिग्बोधकशब्दत्वमेवेत्यभिमानः ॥

(आक्षेपभाष्यम्)

यदि हि यो यो दिशि वर्तते स दिक्शब्दः, रमणीयादिष्वतिप्रसङ्गो भवति—रमणीया दिक् शोभना दिगिति ॥ अथ मतमेतत्—दिशि दृष्टो दिग्दृष्टः दिग्दृष्टः शब्दो दिक्शब्दः यो दिशं न व्यभिचरतीति, न रमणीयादिष्वतिप्रसङ्गो भवति, पुंवद्भावस्तु न प्राप्नोति ॥

(प्रदीपः) दिशि दृष्ट इति । रूढिरूपेण तत्र प्रवृत्त इत्यर्थः । अत एवैन्द्र्यादयो यौगिकत्वान्न दिक्शब्दाः ॥

(उद्द्योतः) दिशि दृष्ट इति । दिशि रूढ्या दृष्ट इत्यर्थः । यो दिशमिति । दिगतिरिक्तमर्थं प्रवृत्तिनिमित्ततयापि यो नाश्रयत इत्यर्थः । एवं च तत्र शब्दस्यैव प्रवृत्तिनिमित्तत्वेन व्यक्तिमात्रशक्ततया वा समानायामाकृतौ भाषितपुंस्कत्वाभाव इति भावः ॥ सर्वनामसंज्ञा तु भवत्येव पृथिवीमध्यात्तत्पर्यन्तदेशरूपोपाधिविशिष्टदिश एव पूर्वादिशब्दवाच्यत्वेन व्यवस्थाविषयत्वाक्षतेरिति दिक् ॥

(समाधानभाष्यम्)

एवं तर्हि "सर्वनाम्नो वृत्तिमात्रे पुंवद्भावो वक्तव्यः दक्षिणोत्तरपूर्वाणामित्येवमर्थम्" ॥

(प्रदीपः) दक्षिणोत्तरपूर्वाणामिति । अत्र हि वैयधिकरण्यात्पुंवद्भावो न प्राप्नोतीत्यवश्यं वाच्यं सर्वनाम्न इति । तेनैव दक्षिणपूर्वेत्यादावपि भविष्यतीति नार्थोऽनेन सूत्रेणेत्यर्थः ॥ २६ ॥ २७ ॥

(प्रत्याख्यानाभ्युपगमभाष्यम्)

एवं च कृत्वास्तु—*दिक्समासबहुयोगयोरन्तरालप्रधानाभिधानात्*इत्येव ॥

(आक्षेपस्मारणभाष्यम्)

ननु चोक्तम्—दक्षिणपूर्वा दिक् समानाधिकरणलक्षणः पुंवद्भावो न प्राप्नोतीति ॥

(समाधानभाष्यम्)

नैष दोषः । सर्वनाम्नो वृत्तिमात्रे पुंवद्भावेन परिहृतः ॥

(१४०५ प्रत्याख्यानबाधकवार्तिकम् ॥ १ ॥)

॥ * ॥ मत्वर्थे वा पूर्वस्य विधानात् ॥ * ॥

(भाष्यम्) अथ वा मत्वर्थे पूर्वो योगः । असमत्वर्थार्थोऽयमारम्भः ॥

(१४०६ प्रत्याख्यानबाधकवार्तिकम् ॥ २ ॥)

॥ * ॥ कबभावार्थो वा ॥ * ॥

(भाष्यम्) अथ वा कप् मा भूदिति ॥ दिङ्नामानि ॥ २६ ॥ तेन सहेति ॥ २७ ॥

(उद्द्योतः) भाष्ये—कबभावार्थो वेति । शेषाधिकारस्य बहुव्रीहावेव तद्विधेरिति भावः ॥ २६ ॥ २७ ॥

(२८६ बहुव्रीहिसंज्ञासूत्रम् ॥ २। २। २। आ. ५ सू.)

४४८ तत्र तेनेदमिति सरूपे ॥२।२।२८॥

(प्रत्याख्याननिराकरणाधिकरणम्)

(१४०७ प्रत्याख्यानवार्तिकम् ॥ १ ॥)

॥ * ॥ तृतीयासप्तम्यन्तेषु च क्रियाभिधानादशिष्यो बहुव्रीहिः ॥ * ॥

(भाष्यम्) तृतीयासप्तम्यन्तेषु चाशिष्यो बहुव्रीहिः । किं कारणम्? । क्रियाभिधानात् । क्रियाभिधीयते । तत्र "अन्यपदार्थे" इत्येव सिद्धम् ॥

(प्रदीपः) तत्र तेनेदम् ॥ २८ ॥ क्रियाभिधानादिति । इतिकरणाद्विवक्षार्थात्केशाकेशि दण्डादण्डीति समासो युद्धक्रियायामेव भवति, सा चान्यपदार्थ इति पूर्वेण सिद्धः समास इत्यर्थः ॥

(उद्द्योतः) तत्रतेनेदम् ॥ २८ ॥ युद्धक्रियायामेवेति । इदं च स्वोक्तोदाहरणविशेषाभिप्रायम् । अत एव कर्णाकर्णि प्रथितमयशः इत्यादिप्रयोगाः संगच्छन्ते । अत एव भाष्ये क्रियाभि-

धानादित्येवोक्तम् ॥ सिद्धः समास इति । पूर्वसूत्रेण । कचित्तु पूर्वेणेति पाठोपि ॥

(१४०८ प्रत्याख्याननिराकरणवार्तिकम् ॥ २ ॥)

॥ * ॥ न वैकशेषप्रतिषेधार्थम् [पूर्वदीर्घार्थं च] ॥ * ॥

(भाष्यम्) नवाऽशिष्यः । किं कारणम् ? । एकशेषप्रतिषेधार्थमिदं वक्तव्यम् ॥

पूर्वदीर्घार्थं च । पूर्वदीर्घार्थं चेदं वक्तव्यम् । केशाकेशि ॥

(प्रदीपः) न वेति । केशेषु केशेषु च गृहीत्वेदं युद्धं दण्डैश्च दण्डैश्च प्रहृत्येदं युद्धमिति ग्रहणे प्रहरणे च सहविवक्षितत्वात् सरूपत्वादेकविभक्तित्वाच्चैकशेषः प्राप्तो वचनसामर्थ्यात्समूहान्यथानुपपत्त्या समूहविषययाऽनया बहुव्रीहिसंज्ञयाऽनवकाशया बाध्यते । पूर्वयोगेण तु परत्वादेकशेषो न शक्यते बाधितुम् । अन्यपदार्थत्वापेक्षत्वात्तस्य बहिरङ्गत्वात् ॥ पूर्वदीर्घार्थं चेति । तत्र तेन आ इदमित्याकारप्रश्लेषेण पूर्वपदस्य दीर्घो विधीयते । उत्तरपदस्य तु यस्येति लोपेन भाव्यमिति प्रयोजनाभावादात्वाभावः ॥

(उद्द्योतः) सरूपत्वादिति । विरूपाणां त्वनभिधानात्समासो नेति भावः ॥ समूहान्यथानुपपत्त्येति । सुप्सुपेत्यधिकारात्तस्याः पदसमूहवृत्तित्वादिति भावः ॥ अन्यपदार्थापेक्षत्वादिति । सुबुत्पत्त्यपेक्षत्वादित्यपि बोध्यम् ॥ पूर्वदीर्घार्थं चेति भाष्ये । इतिशब्दादिदमपि लभ्यमित्येके ॥

(प्रत्याख्यानसाधकभाष्यम्)

स्यादेतत्प्रयोजनं यदि नियोगतोनेनैव दीर्घत्वं स्यात् । अथेदानीम् "अन्येषामपि दृश्यते" इति दीर्घत्वं न प्रयोजनं भवति ॥

(प्रदीपः) अथेदानीमिति । एवं च मुष्टीमुष्टीत्यादि भवति । आकारप्रश्लेषे तु मुष्टामुष्टीति स्यात् ॥

(१४०९ वार्तिकम् ॥ ३ ॥)

॥ * ॥ मत्वर्थे वा पूर्वस्य विधानात् ॥ * ॥

(व्याख्याभाष्यम्)

अथ वा मत्वर्थे पूर्वो योगः । अमत्वर्थार्थोयमारम्भः ॥

(१४१० वार्तिकम् ॥ ४ ॥)

॥ * ॥ कबभावार्थं वा ॥ * ॥

(व्याख्याभाष्यम्)

अथ वा कप् मा भूदिति ॥ तत्र तेनेदम् ॥ २८ ॥

(प्रदीपः) कबभावार्थं वेति । इच् कर्मव्यतिहार इति कबभावपक्षे सावकाशः । पक्षान्तरे तु परत्वाद्बाधित्वा कप् प्राप्नोति । शेषग्रहणेन च शेषाधिकारो गृह्यते नतूपयुक्तादन्यः ॥ २८ ॥

(उद्द्योतः) पक्षान्तरे त्विति । प्रत्याख्यानपक्षे त्वित्यर्थः ॥ नतूपयुक्तादिति । इत्यभिमान इति शेषः ॥ उपयुक्तादन्यः शेष इत्यर्थस्य शेषादिति सूत्रे भाष्यकृतैव स्थापयिष्यमाणत्वात् । आवृत्त्या शेषाधिकारस्यादित्यप्यर्थ इति पूर्वसूत्रस्थकबभावार्थं चेति वार्तिकाज् ज्ञायते । तस्मात्कबभावार्थं वेति अत्रैकदेश्युक्तिः । वैयधिकरण्यात्पूर्वेण न सिध्यतीति अस्य सूत्रस्यावश्यकत्वेऽनेनापि कबभावः सिध्यतीत्याशयेन ॥ २८ ॥

(इति बहुव्रीहिप्रकरणम्)

(अथ द्वन्द्वसमासः)

(२८७ अथ द्वन्द्वसंज्ञासूत्रम् ॥ २ । २ । २ आ. ६ सू.)

४४९ चार्थे द्वन्द्वः ॥ २।२।२९ ॥

(आक्षेपभाष्यम्)

चार्थ इत्युच्यते । चश्चाव्ययम् । तेन समासस्याप्यव्ययसंज्ञा प्राप्नोति ॥

(प्रदीपः) चार्थे ॥ २९ ॥ चार्थ इत्युच्यत इति । यदि तु समाहारेतरेतरयोगयोरित्युच्यते तदा न दोषः स्यात् ॥

(उद्द्योतः) चार्थे द्वन्द्वः ॥ २९ ॥ भाष्ये—चार्थ इत्युच्यते इति । उभयत्रापि साहित्यं समूहो विशेष्यः । स च समाहारेऽनुद्भूतावयवभेदोऽन्यत्र तु विपरीत इत्याशयेनेदम् । यद्यपि चार्थोऽसत्त्वभूतो विशेषणं न तथापि चार्थ इत्यस्य तत्सदृशे इत्यर्थ इति बोध्यम् ॥

(समाधानभाष्यम्)

नैष दोषः । पाठेनाव्ययसंज्ञा क्रियते । न च [द्वन्द्वः] समासस्तत्र पठ्यते ॥

(आक्षेपभाष्यम्)

पाठेनाप्यव्ययसंज्ञायां सत्यामभिधेयवल्लिङ्गवचनानि भविष्यन्ति । यश्चेहार्थोऽभिधीयते न तस्य लिङ्गसंख्याभ्यां योगोस्ति ॥

(उद्द्योतः) पूर्वपक्ष्याह—पाठेनापीति । अपिना पाठेन तस्याः कर्तुमशक्यत्वं सूचितम् । स्वरादिचादयोराकृतिगणत्वात् । अभिधेयवद् विशेष्यवल्लिङ्गादिकं वक्तव्यं विशेष्यस्य चार्थस्य लिङ्गादिराहित्यात्तद्वक्तुमशक्यमिति भावः ॥ नेदं भाष्यं समाहारविषयं तत्र नपुंसकत्वैकवचनयोर्नियतत्वात् । तस्मादितरेतरयोगविषयम् । तच्च तत्र चार्थस्य विशेष्यत्वे संगच्छते नान्यथेति बोध्यम् ॥

(समाधानभाष्यम्)

नेदं वाचनिकम्—अलिङ्गता असंख्यता च । किं तर्हि ? स्वाभाविकमेतत् । तद्यथा—समानमीहमानानां चाधीयानानां च केचिदर्थैर्युज्यन्ते अपरे न । न चेदानीं कश्चिदर्थवानिति कृत्वा सर्वैरर्थ-

वद्भिः शक्यं भवितुम्, कश्चिद्वानर्थक इति सर्वैरनर्थकैः । तत्र किमस्माभिः शक्यं कर्तुम्—यत्प्राक् समासाच्चार्थस्य लिङ्गसंख्याभ्यां योगो नास्ति, समासे च भवति । स्वाभाविकमेतत् ॥

(प्रदीपः) प्राक्समासादिति । वाक्ये चशब्देन द्योत्यस्यार्थस्य लिङ्गसंख्ये न स्तः, समासस्य तु वाचकत्वात् तदर्थस्य लिङ्गसंख्याभ्यां योग इत्यर्थः ॥

(समाधानान्तरभाष्यम्)

अथ वा आश्रयतो लिङ्गवचनानि भविष्यन्ति यथा गुणवचनेषु । गुणवचनानां हि शब्दानामाश्रयतो लिङ्गवचनानि भवन्ति । तद्यथा—शुक्लं वस्त्रं शुक्ला शाटी, शुक्लः कम्बलः, शुक्लौ कम्बलौ, शुक्लाः कम्बला इति यदसौ द्रव्यं श्रितो भवति गुणस्तस्य यल्लिङ्गं वचनं च तद् गुणस्यापि भवति । एवमिहापि यदसौ द्रव्यं श्रितो भवति समासस्तस्य यल्लिङ्गं वचनं च तत्समासस्यापि भविष्यति॥

(प्रदीपः) श्रितो भवति समास इति । समासशब्देन समासार्थश्चार्थ उच्यते तस्य समुच्चितद्रव्याश्रये लिङ्गसंख्ये भविष्यत इत्यर्थः ॥

(उद्द्योतः) समुच्चितद्रव्याश्रये इति । समाहारे तु लिङ्गं वाचनिकम् । वचनमपि द्वन्द्वश्चेत्यादौ एकवचनशब्देन योगतः समाहारस्य निर्देशाज्ज्ञापकसिद्धमिति इतरेतरयोगविषये एव पूर्वपक्षसिद्धान्ताविति भावः । एवं चेतरेतरयोगे समाहारो द्रव्येणाभेदमापन्न एवोच्यते इत्याहुः ॥

(आक्षेपभाष्यम्)

अथेह कस्मान्न भवति—याज्ञिकश्चायं वैयाकरणश्च, कठश्चायं बह्वृचश्च, औक्थिकश्चायं मीमांसकश्चेति ॥

(प्रदीपः) याज्ञिकश्चायमिति । एकस्मिन् धर्मिण्यनेकधर्मसमुच्चयाच्चार्थसद्भावाद् द्वन्द्वसंज्ञाप्रसङ्गः । ततश्चाभ्यर्हितत्वाद्वैयाकरणशब्दस्यैव पूर्वनिपातः स्यात् । तत्पुरुषे तु काणखञ्जवदनियमः । परकार्यत्वे चायं दोषः । एकसंज्ञाधिकारे तु विशेषविहितत्वात्तत्पुरुषसंज्ञैव भवतीति दोषाभावः ॥

(उद्द्योतः) चार्थसद्भावादिति । अत एव तद्विग्रहे चस्य प्रयोगः याज्ञिकत्वसमानाधिकरणवैयाकरणत्ववान्याज्ञिक इति बोध इति भावः । स च वाक्ये चशब्दबलात्समासे समासबलादिति बोध्यम् ॥ वैयाकरणशब्दस्यैवेति । अभ्यर्हितत्वाक्षमायां तु अल्पाच्तरत्वाद्याज्ञिकशब्दस्यैव स स्यादिति बोध्यम् ॥ विशेषेति । चार्थे इति व्यधिकरणधर्मबोधके सावकाशम् ॥

(समाधानभाष्यम्)

शेष इति वर्तते । अशेषत्वान्न भविष्यति ॥

(प्रदीपः) अशेषत्वादिति । विशेषणमित्यत्रोपयुक्तत्वादित्यर्थः ॥

(उद्द्योतः) भाष्ये—अशेषत्वादिति । समासषट्कपदद्योत्यप्रधानार्थस्यैव चार्थसंबन्धित्वे द्वन्द्वः । प्रधानाप्रधानयोरिति न्यायादित्याशयोऽत्र गूढः ॥

(आक्षेपभाष्यम्)

यदि शेष इति वर्तते,
'उपाह्लातं स्थूलसिक्तं तूष्णींगङ्गं महाह्रदम् ॥
द्रोणं चेदशको गन्तुं मा त्वा तासां कृताकृते ॥'
इत्येतन्न सिध्यति ॥

(प्रदीपः) उपाह्लातादयः पञ्च तीर्थविशेषास्तांश्चेत्त्वं गन्तुं शक्तवांस्ततः कृताकृते सुकृतदुष्कृते त्वां मा तासां न तापयत इत्यर्थः । तीर्थस्नानप्रशंसेयम् । कृतं क्षीणं सत्तापयत्यकृतं त्वनिष्टफलहेतुत्वेन । कृताकृते इत्येतदत्रोदाहरणम् । अत्र क्तेन नञ्विशिष्टेनानञिति समासविधानादशेषत्वाद्द्वन्द्वाप्रसङ्गः । कर्मसामान्यं च कृताकृतयोरेकमधिकरणं मत्वा प्रश्नः ॥

(उद्द्योतः) सुकृतदुष्कृते इति । कृताकृतशब्दयोस्तयो रूढिरिति भावः ॥ नन्वत्र वैयधिकरण्यात्कथं क्तेननमित्यस्य प्राप्तिरत आह—कर्मसामान्यं चेति । कर्मसामान्यस्य विशेषाश्रयत्वादिति भावः ॥

(समाधानभाष्यम्)

नैष दोषः । अन्यद्धि कृतम्, अन्यदकृतम् ॥

(प्रदीपः) अन्यद्धि कृतमिति । ततश्च वैयधिकरण्यात् तत्पुरुषाभावाच्छेषत्वमेव । न ह्यत्रैकं कर्माभिधेयत्वेन विवक्षितं किं तर्हि ? भिन्ने कर्मणी समुच्चिते ॥

(उद्द्योतः) भिन्ने । धर्माधर्मलक्षणे ॥ समुच्चिते । मातासामिति क्रियायां समुच्चिते ॥ केचित्तु कृताकृते इत्यस्य पापपुण्ये क्रमेण कृताकृते इत्यर्थमाहुः ॥

(युगपदधिकरणवचनताधिकरणम्)

(१४११ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ चार्थे द्वन्द्ववचनेऽसमासेपि चार्थसंप्रत्ययादनिष्टप्रसङ्गः ॥ * ॥

(व्याख्याभाष्यम्)

चार्थे द्वन्द्ववचने समासेपि चार्थसंप्रत्ययादनिष्टं प्राप्नोति—

'अहरहर्नयमानो गामश्वं पुरुषं पशुम् ॥
वैवस्वतो न तृप्यति सुराया इव दुर्मदी ॥'
इति ॥ 'इन्द्रस्त्वष्टा वरुणो वायुरादित्य' इति ॥

(प्रदीपः) चार्थे द्वन्द्ववचन इति । चार्थानुवादेन द्वन्द्वस्य विधानात् तस्य चानिष्टेऽपि विषये सद्भावादतिप्रसङ्ग इत्यर्थः ॥ दुर्मदीति । दुःखेन यो माद्यति स यथा सुरया न तृप्यति एवं यमो गवादीन्नयमान इत्यर्थः ॥ तत्र नयनक्रियायां गवादीनां समुच्चयाच्चार्थसद्भावादस्ति द्वन्द्वप्राप्तिः ॥

इन्द्र इति । इन्द्रादीनां लोकपालत्वाद् गम्यमानपालनक्रियायां समुच्चयोस्ति ॥

(उद्द्योतः) अतिप्रसङ्ग इति । द्वन्द्वसंज्ञातिप्रसङ्ग इत्यर्थः ॥ गामश्वं पुरुषं पशुमिति वाक्येपि परस्परसाहित्यरूपे इतरेतरयोगे पदानां वृत्तेर्द्वन्द्वसंज्ञा स्यादिति भावः ॥ दुःखेनेति । क्लेशेनेत्यर्थः । अल्पपानेन मदानुत्पत्तिर्यस्येति फलितम् ॥ सुराया इति । शेषषष्ठी । सुरयेत्यर्थः ॥ इन्द्रादीनामिति । भाष्ये 'लोकानां पालकाः' इत्यध्याहार्यमिति भावः ॥

(१४१२ युगपदधिकरणवचनतयासमाधानवार्तिकम् ॥ २)

॥ * ॥ सिद्धं तु युगपदधिकरणवचने द्वन्द्ववचनात् ॥ * ॥

(व्याख्याभाष्यम्)

सिद्धमेतत् ॥ कथम् ? । युगपदधिकरणवचने द्वन्द्वो भवतीति वक्तव्यम् ॥

(प्रदीपः) सिद्धं त्विति । न्यासान्तरेणातिप्रसङ्गपरिहारः । युगपदेकैकेन शब्देनाधिकरणमभिधेयं द्वन्द्ववाच्यं समुदायरूपं यदोच्यते तदा द्वन्द्वः । गामश्वमित्यादौ तु परस्परनिरपेक्षाः स्वतन्त्रा गवादयो भिन्नैरेव शब्दैः पृथक् प्रत्याय्यन्त इति युगपद्वाचित्वाभावाद् द्वन्द्वाभावः ॥

(१४१३ युगपदधिकरणतायां दूषणवार्तिकम् ॥ ३)

॥ * ॥ तत्र पुंवद्भावप्रतिषेधः ॥ * ॥

(भाष्यम्) तत्रैतस्मिन् लक्षणे पुंवद्भावस्य प्रतिषेधो वक्तव्यः । पट्वीमृद्व्यौ । समानाधिकरणलक्षणः पुंवद्भावः प्राप्नोति ॥

(प्रदीपः) पट्वीमृद्व्याविति । एकैकेन शब्देनार्थद्वयस्याभिधानात्सामानाधिकरण्यमस्ति ॥

(१४१४ दूषणान्तरवार्तिकम् ॥ ४)

॥ * ॥ विप्रतिषिद्धेषु चानुपपत्तिः ॥ * ॥

(भाष्यम्) विप्रतिषिद्धेषु युगपदधिकरणवचनताया अनुपपत्तिः । शीतोष्णे सुखदुःखे जननमरणे । किं कारणम् ? । सुखप्रतिघातेन हि दुःखम्, दुःखप्रतिघातेन च सुखम् ॥

(प्रदीपः) विप्रतिषिद्धेषु चेति । ये अर्था अविरुद्धास्तेषां भवत्वेकैकेन शब्देनाभिधानम् । विरुद्धानां तु सहानवस्थानाद् युगपदनुभवाभावात्सहविवक्षाभावाद्युगपद्वाचिता नोपपद्यत इत्यर्थः ॥ आरात्पुरादीनां विरुद्धार्थाभिधानं दृष्ट्वा पृच्छति—किं कारणमिति ॥ सुखप्रतिघातेनेति । आरादादयस्तु युगपद्विरुद्धार्थाभिधायिनो नैवाभ्युपगम्यन्ते ॥

(उद्द्योतः) धवखदिरयोरिवात्रापि सहविवक्षा स्यादत आह—ये अर्था इति ॥ युगपदनुभवाभावादिति । परस्य स्वज्ञानसदृशज्ञानसमर्पणाय शब्दप्रयोग इति भावः ॥ विप्रतिषिद्धत्वादेव युगपदभिधानानुपपत्तौ प्रश्नानुपपत्तिरत आह—आरादिति । तत्र दूरसमीपयोर्वर्तते ॥ पुरेति । चिरातीतभविष्यदासन्नयोर्वर्तते । सुखप्रतिघातेन इत्यादिना सुखप्रतिबन्धिकायास्तन्नाशिकायाश्च सामग्र्या दुःखजनकत्वं दुःखप्रतिबन्धिकायास्तन्नाशिकायाश्च सुखजनकत्वं सूचितम् । एवं दुःखसुखजनकसामग्र्योर्नियमेन सुखदुःखप्रतिबन्धकत्वादिं च सूचितम् । एतेन भारोत्तीर्णे गौणः सुखव्यवहार इत्यपास्तम् ॥

(प्रथमदूषणबाधकभाष्यम्)

यत्तावदुच्यते * तत्र पुंवद्भावप्रतिषेधः * इति । इदं तावदयं प्रष्टव्यः—अथेह पुंवद्भावः कस्मान्न भवति—दर्शनीयाया माता दर्शनीयामातेति ? । अथ मतमेतत्—प्राक् समासाद्यत्र सामानाधिकरण्यं तत्र पुंवद्भावो भवतीति । इहापि न दोषो भवति ॥

(प्रदीपः) दर्शनीयामातेति । वृत्तावेकार्थीभावेन मात्रर्थवृत्तित्वाद्दर्शनीयाशब्दस्य समानाधिकरण्यमत्रास्ति ॥ अथ मतमिति । वृत्तौ सामानाधिकरण्यव्यभिचाराभावाद्यदि वाक्यविषय सामानाधिकरण्यमाश्रीयते तदा पट्वीमृद्व्यावित्यत्रापि न दोषः । लौकिकं च यद्वाक्यं प्रयोगार्हं तत्र सामानाधिकरण्यमाश्रीयते, न त्वलौकिके प्रक्रियावाक्ये पट्व्यौ च मृद्व्यौ चेति ॥

(उद्द्योतः) षष्ठीसमासे कथं सामानाधिकरण्यमत आह—वृत्ताविति ॥ अयं भावः—सामानाधिकरण्यं नाम विशेष्यतयैकद्रव्योपस्थापकत्वम् । तच्चात्रापि पृथक् पूर्वपदेन स्वार्थानुपस्थितेरिति ॥ न दोष इति । अनयैव रीत्या विरूपाणामपीत्येकशेषोपि वारणीयः । द्वन्द्वारम्भसामर्थ्येन वाक्यीयस्य समानार्थत्वस्यैवाश्रयणादिति बोध्यम् ॥ ननु अत्र पक्षे पट्वी चेत्येव वाक्यं समासार्थमिति तत्रापि सामानाधिकरण्यमस्त्येवेत्यत आह—लौकिकं चेति। स्वातन्त्र्येणार्थबोधाय प्रयुक्तमित्यर्थः । इदं त्वलौकिकवृत्तिसमानार्थकमेवेति भावः ॥

(द्वितीयदूषणबाधकभाष्यम्)

यदप्युच्यते *विप्रतिषिद्धेषु चानुपपत्तिः* इति । सर्व एव शब्दाः विप्रतिषिद्धाः । इहापि प्लक्षन्यग्रोधाविति प्लक्षशब्दः प्रयुज्यमानः प्लक्षार्थं संप्रत्याययति, न्यग्रोधार्थं निवर्तयति । न्यग्रोधशब्दः प्रयुज्यमानो न्यग्रोधार्थं संप्रत्याययति, प्लक्षार्थं निवर्तयति । अथात्र चेद्युक्ता युगपदधिकरणवचनता दृश्यते, इहापि युक्ता दृश्यताम् ॥

(प्रदीपः) विप्रतिषिद्धा इति । विप्रतिषिद्धार्था इत्यर्थः । परस्परपरिहारेण सर्वेषामर्थानां शब्दैरभिधानात् ॥ न्यग्रोधार्थमिति । एकस्मिन्नर्थे अवगते अर्थादर्थान्तरस्य निवृत्तिः ॥ इहापीति । विरुद्धानामप्यर्थानामेकशब्दाभिधेय-

ताया अविरोधात् । तथा हि यदा जन्ममरणयोर्विरुद्धयोरप्येकसंज्ञा सहसंप्रत्ययाय क्रियते तदा तच्छब्दवाच्यत्वं तयोर्भवत्येव ॥

(उद्द्योतः) शब्दानां स्वरूपतो विप्रतिपिद्धत्वाभावादाह—**विप्रतिपिद्धार्था इति** ॥ तदप्युपपादयति—**परस्परेति** ॥ भाष्ये—**निवर्तयतीति** । बुद्धित इति शेषः ॥ ननु निवृत्तौ तात्पर्यं चेदपोहवादः । अपोहश्च तदितरभेदस्तद्वान्वा । न चेन्निवृत्तिर्दुर्लभेत्यत आह—**एकस्मिन्निति** ॥ **विरुद्धानामिति** । नहि सहानुभवासंभवः शब्दात्सहबोधे प्रतिबन्धक इति भावः ॥ **एका संज्ञेति** । एको वाचकः शब्द इत्यर्थः ॥

(युगपदधिकरणवचनतानुपपत्तिभाष्यम्)

एवमपि—

(१४१५ युगपदधिकरणवचनताया असंभववार्तिकम् ॥५॥)

॥ * ॥ शब्दपौर्वापर्यप्रयोगादर्थपौर्वापर्याभिधानम् ॥ * ॥

(भाष्यम्) **शब्दपौर्वापर्यप्रयोगादर्थपौर्वापर्याभिधानं प्राप्नोति ॥ अतः किम्? । युगपदधिकरणवचनताया अनुपपत्तिः । प्लक्षन्यग्रोधौ प्लक्षन्यग्रोधा इति । यथैव हि शब्दानां पौर्वापर्यं तद्वदर्थानामपि भवितव्यम् ॥**

(प्रदीपः) इदानीं युगपद्वाचिताया असंभवं प्रतिपादयति—**एवमपीति** । अभिधानक्रमाद् अभिधेयक्रमोऽवतिष्ठते यथा गुणवृद्धी वृद्धिगुणाविति । ततश्च शब्दक्रमात् क्रमवदर्थावगमाच्च संभवत्येकैकेनानेकस्याभिधानमित्यर्थः ॥

(उद्द्योतः) ननु वाचकक्रमो न वाच्यप्रतीतियौगपद्यविरोधीत्यत आह—**अभिधानक्रमेति** ॥ **अभिधेयक्रमः** । अभिधेयज्ञानक्रमः ॥ **क्रमवदर्थावगमादिति** । क्रमवतोऽर्थावगमस्य सत्त्वादित्यर्थः ॥

(१४१६ पौर्वापर्याभिधाने दूषणवार्तिकम् ॥ ६ ॥)

॥ * ॥ शब्दपौर्वापर्यप्रयोगादर्थपौर्वापर्याभिधानमिति चेद्द्विवचनबहुवचनानुपपत्तिः ॥ * ॥

(भाष्यम्) **शब्दपौर्वापर्यप्रयोगादर्थपौर्वापर्याभिधानमिति चेद् द्विवचनबहुवचनयोरनुपपत्तिः—प्लक्षन्यग्रोधौ प्लक्षन्यग्रोधा इति । प्लक्षशब्दः सार्थको निवृत्तो न्यग्रोधशब्द उपस्थितः । एक एकार्थः तस्यैकार्थत्वादेकवचनं प्राप्नोति ॥**

(प्रदीपः) **न्यग्रोधशब्द इति** । न्यग्रोधार्थप्रतिपत्तिकाले यदि प्लक्षार्थस्यानवगतिः स्यात्तदा न्यग्रोधशब्दादेकार्थत्वादेकवचनं स्यात् । तस्माद् द्विवचनबहुवचनान्यथानुपपत्त्या प्लक्षन्यग्रोधावित्यादावेकैकोऽनेकार्थाभिधायीत्यभ्युपगन्तव्यम् ॥

(उद्द्योतः) भाष्ये—**प्लक्षशब्दः सार्थको निवृत्त इति** । अर्थेन सह निवृत्त इत्यर्थः । स्वार्थे कः ॥ ननु तस्य निवृत्तावपि एकेन शब्देन समासरूपप्रातिपदिकेन द्वौ बोधिताविति द्विवचनं भविष्यतीति चेन्न । समासस्य समूहे शक्तावपि प्लक्षादीनामवयवत एव बोधेन एकप्रातिपदिकजन्यबोधविषयत्वाभाव इत्यभिमानात् ॥ **तस्मादिति** । विनिगमनाविरहादुभयोरप्यनेकार्थत्वमित्याशयः ॥

(१४१७ दूषणोद्धारवार्तिकम् ॥ ७ ॥)

॥ * ॥ विग्रहे च युगपद्वचनं ज्ञापकं युगपद्वचनस्य ॥ * ॥

(भाष्यम्) **विग्रहे खल्वपि युगपद्वचनता दृश्यते—'द्यावा ह क्षामा' 'द्यावा चिदस्मै पृथिवी संनमेते' इति ॥ किमेतत्? । युगपदधिकरणवचनताया उपोद्बलकम् ॥ विग्रहे किल नाम युगपदधिकरणवचनता स्यात्, किं पुनः समासे ॥**

(प्रदीपः) एवं युक्त्या युगपद्वाचितां प्रसाध्यागमेन प्रसाधयति—**विग्रहे चेति** । **द्यावेति** । द्योशब्दो द्यावापृथिव्योर्वर्तत इति ततः परस्य प्रथमाद्विवचनस्य **सुपां सुलुगि**त्याकारो **गोतो णिदिति** गोशब्दस्यौकारान्तत्वोपलक्षणार्थत्वाद् णित्त्वाद्वृद्धिरावादेशश्च । एवं पृथिवीशब्दो दिवःपृथिव्यौ वक्तीति प्रथमाद्विवचने **वा छन्दसीति** पूर्वसवर्णदीर्घः ॥ **सन्नमेते इति** द्विवचनान्तेन सामानाधिकरण्यात् **पृथिवी इतीति** पदकारैर्द्विवचनाश्रयप्रगृह्यसंज्ञानिबन्धनस्य प्रकृतिभावस्य विधानाच्च द्व्यर्थत्वं पृथिवीशब्दस्यावसीयते ॥ **किमेतदिति** । यथोक्तमप्रतिपद्य पृच्छति ॥ **उपोद्बलकमिति** । उत्कृष्टबलकमुद्बलकं प्रत्यक्षं तत्समीपमनुमानमुपोद्बलकम् । आगमस्येहानुमानत्वेनोपन्यासात् ॥ **विग्रहे किलेति** । साहचर्यादिनिमित्ताश्रयेण वाक्येपि शब्दानामनेकार्थाभिधायित्वं यदा दृश्यते तदा समासे शक्त्यन्तराणां वाक्येऽदृष्टानामपि दर्शनादसंभावना न कार्येत्यर्थः ॥

(उद्द्योतः) **आगमेन** । अनाशङ्कनीयप्रमादवेदवाक्येन । एतेन द्यावेत्यादावपि द्विवचनानुपपत्तिस्तुल्यत्वात्पूर्वसात् को विशेष इत्यपास्तम् ॥ भाष्ये—**द्यावाहेति** । **द्यावा ह क्षामा प्रथमे ऋतेनेति** मन्त्रस्थमिदं । हशब्दोऽसमासद्योतकः । इतरेतरापेक्षयोभयत्रापि द्विवचनम् । प्रथमे हशब्देन द्वितीये चिदस्मैशब्देन व्यवधानात्समासाभावः । प्रधाने **द्यावापृथिव्या**वित्याद्यमन्त्रार्थे ॥ **यथोक्तं सूचितं** कैमुतिकन्यायम् ॥ **उत्कृष्टेति** । एवं च युगपदधिकरणवचनतायाः सत्त्वस्येदमनुमानमनुमापकमित्यर्थः ॥ **साहचर्यादीति** । **द्यावाहक्षामे**तिवाक्ये परस्परसाहचर्याद् **द्यावाचिदस्मै पृथिवी**त्यत्र साहचर्येण द्विवचनानुपपत्त्या च तथा कल्पनाश्रीयते चेत्किं समासे वक्तव्यमित्यर्थः ॥

(१४१८ द्वितीयदूषणोद्धारवार्तिकम् ॥ ८ ॥)

॥ * ॥ समुदायात्सिद्धम् ॥ * ॥

(भाष्यम्) समुदायात्सिद्धमेतत् ॥ किमेतत्समुदायात्सिद्धमिति ? । द्विवचनबहुवचनताप्रसिद्धिरिति चोदितम्, तस्यायं परिहारः ॥

(प्रदीपः) युगपद्वाचित्वाभावे द्विवचनबहुवचनासिद्धिदोषं परिहर्तुमाह—समुदायादिति । द्वन्द्वेन समुदायरूपोऽर्थोऽभिधीयत इति द्विवचनबहुवचनसिद्धिः ॥

(उद्योतः) द्वन्द्वेनेति । द्वन्द्वरूपसमुदायेनोद्भूतावयवभेदः समूहरूपोऽर्थः प्लक्षादिशब्दक्रमोच्चारणेन यद्यपि क्रमेण बुध्यते, तथापि द्वन्द्वरूपैकप्रातिपदिकजन्यबोधविषयतया द्वयोः सत्त्वेन द्विवचनाद्युपपत्तौ युगपद्वचने मानाभाव इति भावः ॥

(१४१९ दूषणसाधकवार्तिकम् ॥ ९ ॥)

॥ * ॥ समुदायात्सिद्धमिति चेन्नैकार्थत्वात्समुदायस्य ॥ * ॥

(भाष्यम्) समुदायात्सिद्धमिति चेत् । तन्न । किं कारणम् ? । एकार्थत्वात्समुदायस्य । एकार्था हि समुदाया भवन्ति । तद्यथा—शतं यूथं वनमिति ॥

(१४२० दूषणबाधकवार्तिकम् ॥ १० ॥)

॥ * ॥ नैकार्थ्यम् ॥ * ॥

(भाष्यम्) नायमेकार्थः । किं तर्हि ? । द्व्यर्थो बह्वर्थश्च । प्लक्षोऽपि द्व्यर्थः न्यग्रोधोऽपि द्व्यर्थः ॥

(प्रदीपः) नैकार्थ्यमिति । उद्भूतावयवभेदः समुदायोऽभिधेयो न तु तिरोहितावयवभेद इत्यर्थः ॥

(आक्षेपभाष्यम्)

यदि तर्हि प्लक्षोऽपि द्व्यर्थो न्यग्रोधोऽपि द्व्यर्थः,—

(१४२१ दूषणवार्तिकम् ॥ ११ ॥)

॥ * ॥ तयोरनेकार्थत्वाद्बहुवचनप्रसङ्गः ॥ * ॥

(भाष्यम्) तयोरनेकार्थत्वाद् 'बहुषु बहुवचनम्' इति बहुवचनं प्राप्नोति ॥

(प्रदीपः) बहुवचनप्रसङ्ग इति । एकैकेन युगपदनेकस्यार्थस्याभिधानात् ॥

(उद्योतः) एवं खण्डनवादी स्वमते द्विवचनादिकमुपपाद्य युगपदधिकरणवचनतावादं दूषयितुं तन्मतमनुवदति—प्लक्षोऽपि द्व्यर्थो न्यग्रोधोऽपि द्व्यर्थ इति । इति तव मतमिति शेषः ॥ यदि तर्हीति । यद्येवं स्वीकुरुषे इत्यर्थः ॥ यत्तु लघुविवरणे प्लक्षः प्लक्षशब्दघटितो द्वन्द्वरूपः समुदाय इत्यर्थः । द्व्यर्थः अवयवसमुदायार्थः । न्यग्रोधोऽपीत्यपि व्याख्येयमिति ॥ तन्न । न्यग्रोधोऽपीत्यंशस्य वैयर्थ्यापत्तेः । यदि तर्हीत्यादेरनुत्थानापत्तेश्च । न च प्रागुक्ताशयमविदुषो युगपद्वचनतावादिनोऽयं पूर्वपक्ष इति वाच्यम् । तत्समाधानकाले पूर्वोक्तस्वाशयप्रकटनेनैव समाधानस्योचितत्वेन याभ्यामेवार्थको द्व्यर्थस्ताभ्यामेवापरोऽपीत्यादि तत्समाधानपरग्रन्थासंगतेः । तद्ग्रन्थस्यारम्भेन युगपदधिकरणवचनतावादिन एवैतत्पूर्वपक्षे सिद्धान्तित्वप्रतीतेः ॥

(१४२२ दूषणोद्धारसमाधानवार्तिकम् ॥ १२ ॥)

॥ * ॥ तयोरनेकार्थत्वाद्बहुवचनप्रसङ्ग इति चेन्न बहुत्वाभावात् ॥ * ॥

(भाष्यम्) तयोरनेकार्थत्वाद्बहुवचनप्रसङ्ग इति चेत् ॥ तन्न । किं कारणम् ? । बहुत्वाभावात् । नात्र बहुत्वमस्ति ॥ किमुच्यते—बहुत्वाभावादिति, यदा इदानीमेवोक्तम्—प्लक्षोऽपि द्व्यर्थो न्यग्रोधोऽपि द्व्यर्थ इति ? । याभ्यामेवार्थको द्व्यर्थस्ताभ्यामेवापरोऽपि ।

(प्रदीपः) याभ्यामेवेति । नात्र चत्वारोऽर्थाः ? किं तर्हि द्वावेवार्थावित्यर्थः ॥

(द्विवचनबहुवचनानुपपत्तिभाष्यम्)

यद्येवम्—

(१४२३ अनुपपत्तिवार्तिकम् ॥ १३ ॥)

॥ * ॥ अन्यवाचकेनान्यस्य वचनानुपपत्तिः ॥ * ॥

(भाष्यम्) अन्यवाचकेन शब्देनान्यस्य वचनं नोपपद्यते ॥

(प्रदीपः) अन्यवाचकेनेति । लौकिकात् प्रयोगात् शब्दानामर्थावधारणं तत्र यथा पटशब्दः घटार्थं न प्रत्याययति तथा प्लक्षन्यग्रोधशब्दौ परस्परार्थस्य प्रत्यायकौ न युक्तावित्यर्थः ॥

(उद्योतः) ननु प्लक्षन्यग्रोधयोरुभयार्थत्वमिति वदतोऽन्यवाचकत्वमसिद्धमत आह—लौकिकादिति ॥

(१४२४ अनुपपत्तिबाधकवार्तिकम् ॥ १४ ॥)

॥ * ॥ अन्यवाचकेनान्यस्य वचनानुपपत्तिरिति चेत् प्लक्षस्य न्यग्रोधत्वाद् न्यग्रोधस्य प्लक्षत्वात् स्वशब्देनाभिधानम् ॥ * ॥

(भाष्यम्) अन्यवाचकेनान्यस्य वचनानुपपत्तिरिति चेद् ॥ एवमुच्यते—तन्न । किं कारणम् ? । प्लक्षस्य न्यग्रोधत्वाद् न्यग्रोधस्य च प्लक्षत्वाच्च स्वशब्देनाभिधानं भविष्यति । प्लक्षोऽपि न्यग्रोधः न्यग्रोधोऽपि प्लक्षः ॥

(प्रदीपः) **प्लक्षस्येति** । प्लक्षशब्दस्य न्यग्रोधार्थत्वान्न्यग्रोधशब्द प्लक्षार्थाभिधायित्वात् स्वार्थस्यैवाभिधानेन नास्त्यर्थान्तरागित्वम् । लोकप्रसिद्ध्या त्वर्थान्तराभिधायित्वमुच्यते । वृत्तिविषये त्वेकैकस्य द्वावर्थाविति स्वार्थावेव तौ भवतः ॥ **प्लक्षोपि न्यग्रोध इति** । न्यग्रोधशब्दवाच्य इत्यर्थः । एवं न्यग्रोधोऽपि प्लक्षशब्दवाच्य इत्यर्थः ॥

(उद्द्योतः) नन्वस्यान्यरूपत्वाभावेन प्लक्षस्य न्यग्रोधत्वादित्यनुपपन्नमत आह—**प्लक्षशब्दस्येति** ॥

(आक्षेपभाष्यम्)

कथं पुनः प्लक्षोपि न्यग्रोधः न्यग्रोधोपि प्लक्षः स्यात्, यावता 'कारणाद् द्रव्ये शब्दनिवेशः?' ॥

(प्रदीपः) **कारणादिति** । शब्दार्थावसायहेतुर्लोकव्यवहारोत्र कारणशब्देन विवक्षितः ॥ न च लोकव्यवहारे प्लक्षशब्दस्य न्यग्रोधाभिधायित्वं प्रतीतम् ॥

(उद्द्योतः) भाष्ये प्लक्षशब्दस्य न्यग्रोधार्थत्वं कथमितिप्रश्नोपपादकं—**यावतेति** । यत इत्यर्थः । तद्व्याचष्टे—**शब्दार्थावसायेति** । शब्दार्थसंबन्धग्रहणेत्यर्थः ॥

(१४२५ वार्तिकम् ॥ १५ ॥)

॥ * ॥ कारणाद् द्रव्ये शब्दनिवेश इति चेत्तुल्यकारणत्वात्सिद्धम् ॥ * ॥

(भाष्यम्) **कारणाद् द्रव्ये शब्दनिवेश इति चेद् ॥ एवमुच्यते—तन्न । तुल्यकारणत्वात् सिद्धम् । तुल्यं हि कारणम् । यदि तावत्प्रक्षरतीति व्युत्पत्त्या प्लक्षः स्याद्, न्यग्रोधेप्येतद्भवति । तथा यदि न्यग्रोहतीति न्यग्रोधः, प्लक्षेप्येतद्भवति** ॥

(प्रदीपः) इतरः शब्दप्रवृत्तिनिमित्तं शब्दप्रयोगस्य कारणमिति मत्वाह—**कारणादिति** । **प्रक्षरणं** विस्तारेणावस्थानम् । **न्यग्रोहणम**धःशाखावस्थापनम् ॥

(१४२६ वार्तिकम् ॥ १६ ॥)

॥ * ॥ दर्शनं वै हेतुः ॥ * ॥

(भाष्यम्) **न च न्यग्रोधे प्लक्षशब्दो दृश्यते** ॥

(प्रदीपः) इतरः स्वाभिप्रायं प्रकाशयति—**दर्शनमिति** । लोकव्यवहार इत्यर्थः ॥

(१४२७ वार्तिकम् ॥ १७ ॥)

॥ * ॥ दर्शनं हेतुरिति चेत्तुल्यम् ॥ * ॥

(भाष्यम्) **दर्शनं हेतुरिति चेत्तुल्यमेतद्भवति प्लक्षेपि न्यग्रोधशब्दो दृश्यते न्यग्रोधेपि प्लक्षशब्दः । तुल्यं हि कारणम्** ॥

(प्रदीपः) **प्लक्षेपीति** । लोकव्यवहारे प्लक्षन्यग्रोधौ दृश्येतामित्युभयोः क्रियान्वयाद् द्विवचनदर्शनाच्च ॥ **तुल्यं हीति** । तुल्यो लोकव्यवहार इत्यर्थः ॥

(उद्द्योतः) प्लक्षेपि न्यग्रोधशब्दो दृश्यत इत्युक्तं तत्र दर्शनमुपपादयति—**लोकव्यवहारे प्लक्षेति** । पूर्वोक्तेन शब्दप्रयोगक्रमेणार्थज्ञानकत्वादुभयोः क्रियान्वयो द्विवचनं च न स्यादित्यभिमानः ॥ भाष्ये—**तुल्यं हि कारणमिति** । दर्शनरूपं कारणमपि तुल्यमित्यर्थस्तदाह—**तुल्यो लोकेति** ।

(आक्षेपभाष्यम्)

न वै लोके एष संप्रत्ययो भवति । न हि प्लक्ष आनीयतामित्युक्ते न्यग्रोध आनीयते ॥

(उद्द्योतः) पुनर्भाष्ये शङ्कते—**न वै लोक इति** ॥

(१४२८ समाधानवार्तिकम् ॥ १८ ॥)

॥ * ॥ तद्विषयं च ॥ * ॥

(भाष्यम्) **तद्विषयं चैतद् द्रष्टव्यं प्लक्षस्य न्यग्रोधत्वम् ॥ किं विषयम्? । द्वन्द्वविषयम्** ॥

(प्रदीपः) **तद्विषयं चेति** । द्वन्द्वावयवानामेवानेकार्थाभिधायित्वं न केवलानामित्यर्थः ॥

(आक्षेपभाष्यम्)

युक्तं पुनर्यन्नियतविषया नाम शब्दाः स्युः? ॥

(प्रदीपः) **युक्तं पुनरिति** । किं युक्तमेनदित्यर्थः ॥

(उद्द्योतः) **किं युक्तमेतदिति** । युक्तं पुनरित्यत्र काका प्रश्नो व्यङ्ग्य इति भावः ॥

(समाधानभाष्यम्)

वाढं युक्तम् ॥

(१४२९ समाधानसाधकवार्तिकम् ॥ १९ ॥)

॥ * ॥ अन्यत्रापि तद्विषयदर्शनात् ॥ * ॥

(भाष्यम्) **अन्यत्रापि हि नियतविषयाः शब्दा दृश्यन्ते । तद्यथा—समाने रक्ते वर्णे गौर्लोहित इति भवति, अश्वः शोण इति । समाने च कालेवर्णे गौः कृष्ण इति भवति, अश्वो हेम इति । समाने च शुक्ले वर्णे गौः श्वेत इति भवति, अश्वः कर्क इति** ॥

(प्रदीपः) **वाढमिति** । भिन्नरूपत्वाद्भिन्नशक्तित्वाच्च ॥ **अश्वः शोण इति** । यथाश्वादन्यत्र शोणादयो न वर्तन्ते तथा विना द्वन्द्वात् प्लक्षादयो न्यग्रोधाद्यर्था न भवन्तीत्यर्थः ॥

(उद्द्योतः) **भिन्नरूपत्वादिति** । प्लक्षो दृश्यतामित्यादौ सविभक्तिकम्, समासे निर्विभक्तिकमित्यर्थः ॥ **भिन्नशक्तित्वादिति** । तत्र भिन्नोपस्थितिजनिका शक्तिः, समासे एकोपस्थितिजनिकेत्यर्थः ॥

(आक्षेपभाष्यम्)

यदि तर्हि प्लक्षोपि न्यग्रोधः न्यग्रोधोपि प्लक्षः—

(१४३० आक्षेपवार्तिकम् ॥ २० ॥)

॥ * ॥ एकेनोक्तत्वादपरस्य प्रयोगोऽनुपपन्नः ॥ * ॥

(भाष्यम्) एकेनोक्तत्वात्तस्यार्थस्यापरस्य प्रयोगो नोपपद्यते—प्लक्षेण न्यग्रोधस्य न्यग्रोधप्रयोगः ॥

(प्रदीपः) यदि तर्हीति । ननु तद्विपर्यं चेत्युक्ते कोस्य दोषस्यावसरः । एवं मन्यते—परस्परसन्निधानेन यदा द्वयोरपि सामर्थ्यमाहितं तदान्यतरविगमेपि सामर्थ्यहानाभावो यथा वह्निसंपादितपाकजरूपादिसद्भावो निवृत्तेऽपि वह्नौ ॥

(उद्योतः) भाष्ये—प्लक्षेण न्यग्रोधस्य न्यग्रोधप्रयोग इति । प्लक्षशब्देन न्यग्रोधरूपार्थस्योक्तत्वान्न्यग्रोधशब्दप्रयोगो नोपपद्यत इत्यर्थः ॥

(१४३१ वार्तिकम् ॥ २१ ॥)

॥ * ॥ एकेनोक्तत्वादपरस्य प्रयोगोनुपपन्न इति चेदनुक्तत्वात्प्लक्षेण न्यग्रोधस्य न्यग्रोधप्रयोगः ॥ * ॥

(भाष्यम्) एकेनोक्तत्वादपरस्य प्रयोगोनुपपन्न इति चेत् । तन्न । किं कारणम्? । अनुक्तत्वात्प्लक्षेण न्यग्रोधस्य न्यग्रोधप्रयोगः । अनुक्तः प्लक्षेण न्यग्रोधार्थ इति कृत्वा न्यग्रोधशब्दः प्रयुज्यते ॥ कथमनुक्तः, यावता इदानीमेवोक्तं प्लक्षोपि न्यग्रोधः न्यग्रोधोपि प्लक्ष इति?। सहभूतावेतावन्योन्यस्यार्थमाहतुः । न पृथग्भूतौ ॥

(प्रदीपः) अनुक्त इति । न्यग्रोधशब्दप्रयोगमन्तरेणेत्यर्थः । उक्तं ह्येतत्—द्वन्द्वावयवानामेवानेकार्थाभिधायित्वं न केवलानां यथा वह्निसंनिधावेव ताम्रं द्रवरूपं भवति न तु तद्विनिवृत्तौ ॥ सहभूताविति । आरोद्यन्तृवत्परस्परशक्त्याविर्भावात् ॥

(उद्योतः) युगपदभिधानमनुक्तिश्च विरुद्धेत्यत आह—न्यग्रोधशब्देति ॥ आरोढ्रिति । इतरसन्निधाने एव शक्त्याविर्भावो न केवलस्यापीति भावः ॥

(आक्षेपभाष्यम्)

किं पुनः कारणं सहभूतावेतावन्योन्यस्यार्थमाहतुर्न पृथग्भूतौ ? ॥

(१४३२ समाधानवार्तिकम् ॥ २२ ॥)

॥ * ॥ अभिधानं पुनः स्वाभाविकम् ॥*॥

(भाष्यम्) स्वाभाविकमभिधानम् ॥

(समाधानभाष्यम्)

अथ वेह कौ चित्प्राथमकल्पिकौ प्लक्षन्यग्रोधौ, कौ चित्क्रियया वा गुणेन वा, प्लक्ष इवायं प्लक्षः—न्यग्रोध इवायं न्यग्रोध इति । तत्र प्लक्षावित्युक्ते संदेहः स्यात्—किमिमौ प्लक्षावेव आहोस्वित्प्लक्षन्यग्रोधाविति । तत्रासंदेहार्थं न्यग्रो शब्दः प्रयुज्यते ॥

(प्रदीपः) प्राथमकल्पिकाविति । लोकव्यवहारे पदोच्चारणमात्रात्तदर्थावसायान्मुख्यावित्यर्थः ॥ कौ चिदिति । तत्सहचरितगुणक्रियादर्शनात्तद्रूपारोपणाद् गौणावित्यर्थः । यथोक्तम्—यदि प्रक्षरतीत्यादि ॥ संदेहः स्यादिति । उपक्रमे संदेहो गौणस्याप्यर्थस्य संभवमात्रेण । न तु मुख्यार्थसंभवे गौणस्य परामर्श एवास्ति तत्कृतः संदेहः ॥

(उद्योतः) किमिमौ प्लक्षावेवेति भाष्यस्य मुख्यौ प्लक्षावित्यर्थः ॥ तत्कृत इति । तस्माद् न्यग्रोधप्रतीतिरेव न स्यादतो न्यग्रोधशब्दप्रयोग आवश्यक इति बोध्यम् । गौणस्याप्यस्य प्लक्षन्यग्रोधावित्यादौ लोकव्यवहारे परस्य प्रसिद्धत्वान्मुख्यसमकक्षतया भाष्ये सन्देह उक्त इत्यन्ये ॥

(पूर्वपक्षिण आक्षेपोपसंहारभाष्यम्)

सेयं युगपदधिकरणवचनता नाम दुःखा च दुरुपपादा च । यच्चाप्यस्या निबन्धनमुक्तम्—द्यावा ह क्षामेति, तदपि च्छान्दसम् । तत्र सुपां सुपो भवन्तीत्येव सिद्धम् । सूत्रं च भिद्यते ॥

(प्रदीपः) भाष्यकारः सूत्रन्यासं स्थापयितुमाह—सेयमिति ॥ दुःखेति । प्रतीतावनुपारोहात् ॥ दुरुपपादेति । प्रमाणाभावात् । वृद्धव्यवहाराद्धि शब्दार्थावसायः । न च तत्र प्लक्षशब्दस्य प्लक्षन्यग्रोधाभिधायित्वं दृश्यते । न च गौणार्थत्वं प्लक्षशब्दस्य । न्यग्रोधशब्देनैव न्यग्रोधस्य प्रतिपादितत्वात् । न च प्लक्षन्यग्रोधावित्युक्तेऽर्थद्वयप्रतीतेरावृत्तिः यथा प्लक्षन्यग्रोधौ प्लक्षन्यग्रोधाविति । समासस्य चानेकार्थाभिधायित्वात्ततः परयोर्द्विवचनबहुवचनयोरुपपत्तिरिति द्विवचनबहुवचनान्यथानुपपत्त्यापि नास्ति युगपद्वाचिताप्रतिपत्तिः॥ लिङ्गदर्शनमपि निराकुर्वन्नाह—यच्चापीति । एकवचनस्य स्थाने द्विवचनमित्यर्थः ॥

(उद्योतः) प्रतीताविति । समुदायेन द्वयोरुपस्थितिरित्येवानुभवो न तु प्रत्येकं व्यर्थतानुभव इत्यर्थः ॥ समासस्य चानेकार्थेति । अनेकार्थबोधकत्वादित्यर्थः । उद्भूतावयवभेदसमुदायाभिधानशक्तिरुभयोः पर्याप्ता क्रमप्रयोगवद्भिरपि पदैः क्रमेणैकव बुद्धिः समूहालम्बनज्ञानवदिति भावः ॥ द्विवचनमित्यर्थ इति । अत एव पृथिवीत्यस्य प्रगृह्यत्वोपपत्तिरिति भावः । द्वितीयबोधस्तु एकत्र क्षामापदेन, अपरत्र द्यावापदेन । अत एव सन्नमंत इति द्विवचनोपपत्तिः । देवदत्तश्च यज्ञदत्तश्च तिष्ठत इति वत् ॥

(सिद्धान्तिसमाधानभाष्यम्)

यथान्यासमेवास्तु ॥

(आक्षेपस्मारणभाष्यम्)

ननु चोक्तम्—*चार्थे द्वन्द्ववचनेऽसमासेऽपि चार्थसंप्रत्ययादनिष्टप्रसङ्गः* इति ॥

(समाधानभाष्यम्)

नैष दोषः । इह "चे द्वन्द्वः" इतीयता सिद्धम् ॥

कथं पुनश्चे नाम वृत्तिः स्यात् । शब्दो ह्येषः ? ॥

शब्दे कार्यासंभवादर्थे कार्यं विज्ञास्यते । सोयमेवं सिद्धे सति यदर्थग्रहणं करोति तस्यैतत्प्रयोजनम्—एवं यथा विज्ञायेत—चेन कृतोर्थश्चार्थ इति ॥

कः पुनश्चेन कृतोर्थः ? ॥ समुच्चयः अन्वाचय इतरेतरयोगः समाहार इति ॥ समुच्चये—प्लक्षश्चेत्युक्ते गम्यते एतद्—न्यग्रोधश्चेति, तथा न्यग्रोधश्चेत्युक्ते गम्यते एतत्—प्लक्षश्चेति ॥ अन्वाचये—प्लक्षश्चेत्युक्ते गम्यते एतत्—'सापेक्षोयं प्रयुज्यते' इति ॥ इतरेतरयोगे—प्लक्षश्च न्यग्रोधश्चेत्युक्ते गम्यते एतत्—'प्लक्षोपि न्यग्रोधसहायो न्यग्रोधोपि प्लक्षसहायः' इति ॥ [प्लक्षश्च न्यग्रोधश्चेत्युक्ते] समाहारेऽपि क्रियते—प्लक्षन्यग्रोधमिति ॥ तत्रायमप्यर्थः—द्वन्द्वैकवद्भावो न पठितव्यो भवति । समाहारैकत्वादेव सिद्धम् ॥

(प्रदीपः) **चेन कृतोर्थ इति ।** अर्थशब्दस्य सन्निधानादुत्तरपदलोपी समास आश्रीयत इत्यर्थः ॥ ननु चेनार्थस्य कृतत्वमुत्पादनं वा स्यात् प्रकाशनं वा । तत्रोत्पादनं तावन्नोपपद्यते । नहि शब्दैरर्था उत्पाद्यन्ते । यथोक्तम्—'नहि शब्दकृतेन नामार्थेन भवितव्यम्' इति । अथ प्रकाशनम्, तदा स एवातिप्रसङ्ग इति मत्वा पृच्छति—**कः पुनरिति ॥ समुच्चय इति ।** यदा परस्परनिरपेक्षाः पदार्थाः क्रियायां समुच्चीयन्ते तदा समुच्चयश्चार्थो यथा गामश्वं पुरुषमित्यादौ । वाक्ये परस्परानपेक्षा गवादयो नयनक्रियया संबध्यन्ते । तत्र चेन कृतोर्थ इत्यवधारणमर्थग्रहणसामर्थ्यादाश्रीयते—चेनैव यः प्रकाशितोर्थस्तत्र द्वन्द्वः । गामश्वमित्यत्र तु विनाऽपि चेन समुच्चयावगमान्नासौ चेनैव प्रकाशित इत्युच्यते । सामर्थ्यं ह्येकक्रियाद्वारकं दध्योदनादिवत्स्यादिति नात्रासामर्थ्यात्समासपरिहारो वाच्यः ॥ **प्लक्षश्चेत्युक्तइति ।** न्यग्रोधो दृश्यतामित्युपक्रम्य यदा प्लक्षश्चेत्युच्यते । तदा न्यग्रोधश्चेति गम्यते । यदा त्वेकस्य प्राधान्यं तदा इतरस्य तदनुरोधेन क्रियासंबन्धाद्भिन्नकक्ष्यतया नास्ति परस्परेण सामर्थ्यमिति अन्वाचये समासाभावः । प्रधानाभिधायि पदं चार्थे न वर्ततेऽपि त्वप्रधानमेवेति अनेकस्य पदस्य चार्थवृत्तित्वाभावाद् द्वन्द्वाभावः ॥ इतरेतरयोगः परस्परापेक्षाणामनेकेषामेकस्मिन्नर्थे समन्वये सति भवतीति परस्परसहितता चशब्देनैव द्योत्यते इति तत्र समासो भवति ॥ **समाहारेपीति ।** तत्रापि परस्परसहिततावगमात् ॥ **द्वन्द्वैकवद्भाव इति ।** युगपदधिकरणवचनतायां द्वन्द्वे तु वक्तव्यः स्याद् एकैकस्यानेकार्थत्वात् । न च विषयविभागार्थोसौ वक्तव्यः, प्रयोगदर्शनाद्विषयविभागस्य सिद्धत्वात् ॥

(उद्द्योतः) **परस्परनिरपेक्षा इति ।** न्यग्रोधश्छिद्यतां प्लक्षश्चेत्युक्ते न्यग्रोधस्य च्छेदनान्वये प्लक्षापेक्षाया अभावमात्रेण परस्परनिरपेक्षत्वमित्यर्थः ॥ नन्वेतावतोक्तेऽहरहर्नयमान इत्यादौ कथं समासप्रसङ्गो वारितोऽत आह—**तत्र चेनेति ॥ चेनाप्यचेनापीति ।** चं विनापीत्यर्थः । क्वचित्तु विनापि चेनेत्येव पाठः ॥ ननु समुच्चयेऽसामर्थ्यात्कथं समासप्राप्तिरत आह—**सामर्थ्यं हीति ।** इदं तु चिन्त्यम् । कुतः सर्वो मृत्तिकयेत्यादौ समासापत्तेः । किं च क्रियाद्वारके सामर्थ्ये दध्योदनादाविव सामर्थ्यस्य द्वारभूतक्रियायाः पृथक् प्रयोगानापत्तिः । किं चैवं सति सूत्रस्य चार्थपदविग्रहमुक्त्वा पुनस्तदर्थप्रश्ने समुच्चयोद्देशासङ्गतिः, एकगर्भार्थेन सौत्रेण तदप्रतीतेः । किं च गामश्वं पुरुषं पशुमित्यत्र सर्वत्र नैरपेक्ष्ये समुच्चयोपि कथं, समुच्चये एकत्र सापेक्षत्वात् ॥ भाष्ये—**प्लक्षश्चेत्युक्ते इति ।** न्यग्रोधो दृश्यतामित्युपक्रमोक्तौ तु न प्लक्षश्चेति गम्यत इति भावः ॥ **न्यग्रोधश्चेत्युक्ते इति ।** प्लक्षो दृश्यतामित्युपक्रम्य न्यग्रोधश्चेत्युक्ते इत्यर्थः ॥ **सापेक्षोयमिति ।** प्रधानीभूतक्रिययेत्यर्थः । तदाह—**यदा त्विति ॥ इतरस्येत्यस्य** तदेत्यादिः ॥ **भिन्नकक्ष्यतया** भिन्नक्रियान्वयितया ॥ [**अन्वाचये सलोपश्चेत्युक्ते** इति पाठः ॥] तत्रैव सामर्थ्याभावे युक्त्यन्तरमाह—**अनेकस्य पदस्येति ।** इदं समुच्चयेपि बोध्यम् । एवं च समुच्चयेप्यनेकस्य चार्थवृत्तित्वाभावात्समासपरिहार इति प्रागुक्तमसङ्गतमेवेति बोध्यम् ॥ **परस्परापेक्षाणामिति ।** एतेन व्यपेक्षासामर्थ्यवादे द्वन्द्वेऽनुपपत्तिरित्यपास्तम् । परस्परान्वयित्ववदितरान्वये परस्परापेक्षत्वस्यापि व्यपेक्षात्वात् सा च प्रकृतेस्त्येवेति भावः । एतद्विपर्ययश्च समुच्चयादौ दर्शित एव ॥ परस्परापेक्षाणामित्यनेन समुच्चयाद्वैलक्षण्यमुक्तम् । अत एव भाष्ये—**प्लक्षश्चेत्युक्ते गम्यत एतन्न्यग्रोधश्चेति** समुच्चयस्याकारः प्रदर्शितः । तेन ह्येकः परसाहित्यमपेक्षते न पर इतरसाहित्यमित्युक्तम् ॥ अपि चानेन समुच्चये साहित्यं विशेषणमित्युक्तम् । न्यग्रोधसहितः प्लक्ष इति हि तदर्थः । अतोपि तत्र न समासः । चार्थप्राधान्ये एवैतत्समासप्रवृत्तेः । इतरेतरयोगस्य **प्लक्षश्च न्यग्रोधश्चेत्युक्ते गम्यत एतत्, प्लक्षोपि न्यग्रोधसहायो न्यग्रोधोपि प्लक्षसहाय** इति आकारः प्रदर्शितः । अनेनोद्भूतावयवभेदसाहित्यस्य विशेष्यतेति दर्शितम् । एवं च समुच्चयान्वाचययोश्चकारो द्योतकः । अन्त्ययोस्तु वाचकः, तत्र तदर्थस्य

विशेष्यत्वादिति बोध्यम् । तस्मात् **गामश्वमित्यादौ** न समुच्चयः । विनिगमनाविरहेण सर्वेषां परस्परसाहित्यावगतेः अहरहःशब्देन तथैव प्रतीतेः । चार्थसाहित्यावगतिसद्भावेन समासप्राप्तिशङ्का । उत्तरं तु चशब्देन साहित्यं वाच्यं यत्र प्राधान्येन भासते, वृत्तौ चाभावे च समासेन, तत्र समासशास्त्रप्रवृत्तिः । चकारार्थे वर्तमानानेकसुबन्तसत्त्वात् । **गामश्वमित्यादौ** तु अहरहःशब्देन साहित्यं गम्यते, न तु चेनेति भाष्यार्थः । समुच्चयेपि शाब्दबोधे एकत्रैव साहित्यं बुध्यते एकोत्तरं चप्रयोगाद् इत्यनेकसुबन्तस्य प्रधानभूतचार्थे वृत्त्यभावात्समासाभाव इत्ययमर्थश्च भगवता समुच्चयान्वाचयस्वरूपनिरूपणेनैव दर्शितः ॥ अत एव **सन्नियोगशिष्टपरि**भाषापि न्यायसिद्धेति भाष्यतात्पर्यम् ॥ **इन्द्रस्त्वष्टा वरुण** इत्यादावपि परस्परसाहित्येनैव लोकपालत्वं बुध्यत इति बोध्यम् ॥ **तत्रापीति** । परं त्वनुद्भूतावयवभेदमिति भावः ॥ भाष्ये—**समाहारेपीति** पृथग्वाक्यम् । अत्र **प्लक्षोपि न्यग्रोधसहाय** इत्याद्यनुकृष्यते । अनुद्भूतावयवभेदसाहित्यावगतिरिति विशेषः । अनुद्भूतावयवभेदमेव साहित्यं समाहारशब्देनोच्यते । तदाह—**क्रियत इति** । द्वन्द्व इति शेषः ॥ सूत्रारम्भे प्रयोजनान्तरमाह—**तत्रायमपीति** । द्वन्द्वैकवद्भाव इति ग्रन्थेन पक्षान्तरे गौरवं प्रदर्शयन्नाह—**युगपदिति** ॥ **नचविषयेति** । नियमार्थमित्यर्थः ॥ वस्तुतो द्वन्द्वैकवदित्यस्य **सर्वो द्वन्द्वो विभाषयैकवदि**ति वचनं न कार्यमित्यर्थं इति न दोषः ॥

(एकादशादिशब्दार्थनिर्णयाधिकरणम्)

(आक्षेपभाष्यम्)

एकादश द्वादशेति कोयं समासः ? ॥

(१४३३ समाधानवार्तिकम् ॥ २३ ॥)

॥ * ॥ एकादीनां दशादिभिर्द्वन्द्वः ॥ * ॥

(भाष्यम्) **एकादीनां सह दशादिभिर्द्वन्द्वः समासः ॥**

(प्रदीपः) **दशादिभिरिति** । आदिशब्देन विंशत्यादयो गृह्यन्ते । विंशत्याद्यर्थ एव चायं विचारः । दशशब्देन तु द्वन्द्वे न कश्चिद्दोषः ॥

(उद्द्योतः) **न कश्चिद्दोष इति** । एकादशादीनां नित्यबहुवचनान्तत्वादिति भावः ॥

(१४३४ आक्षेपवार्तिकम् ॥ २४ ॥)

॥ * ॥ एकादीनां दशादिभिर्द्वन्द्व इति चेद्विंशत्यादिषु वचनप्रसङ्गः ॥ * ॥

(भाष्यम्) **एकादीनां दशादिभिर्द्वन्द्व इति चेद्विंशत्यादिषु वचनं प्राप्नोति । एकविंशतिः । द्वाविंशतिः ॥**

(प्रदीपः) **वचनमिति** । द्विवचनं बहुवचनं चेत्यर्थः ॥

(उद्द्योतः) न केवला प्रकृतिरिति समयादन्चनमिष्यत एतान आह—**द्विवचनमिति** । उभयोः संख्यापरत्वे द्विवचनं संख्येयपरत्वे बहुवचनं प्राप्नोति, इष्यते त्वेकवचनमिति भावः ॥

(१४३५ समाधानवार्तिकम् ॥ २५ ॥)

॥ * ॥ सिद्धं त्वधिकान्ता संख्या संख्यया समानाधिकरणाधिकारेऽधिकलोपश्च ॥ * ॥

(भाष्यम्) **सिद्धमेतत् ॥ कथम्? । समानाधिकरणाधिकारे वक्तव्यम्—'अधिकान्ता संख्या संख्यया सह समस्यतेऽधिकशब्दस्य च लोपो भवति' इति । एकाधिका विंशतिः एकविंशतिः, द्व्यधिका विंशतिः द्वाविंशतिः ॥**

(प्रदीपः) **सिद्धं त्विति** । शाकपार्थिवादित्वात् ॥

(दूषणभाष्यम्)

यदि समानाधिकरणः, स्वरो न सिध्यति ॥ यद्धि तत्—'संख्या पूर्वपदं प्रकृतिस्वरं भवति' इति, 'द्वन्द्वे' इत्येवं तत् ॥

(प्रत्याक्षेपभाष्यम्)

किं पुनः कारणं द्वन्द्व इत्येवं तत् ? ॥

(समाधानभाष्यम्)

इह मा भूत्—शतसहस्रमिति ॥

(प्रदीपः) **शतसहस्रमिति** । षष्ठीसमासः ॥

(उद्द्योतः) **षष्ठीसमास इति** । सहस्राणां शतमिति विग्रहः । **संख्याया अल्पीयस्या** इति शतस्य पूर्वनिपातः । **तदस्मिन्नधिकमिति** सूत्रे भाष्ये ध्वनितमेतत् ॥

(द्वन्द्वाभ्युपगमभाष्यम्)

अस्तु तर्हि द्वन्द्वः ॥

(उद्द्योतः) भाष्ये—**अस्तु तर्हि द्वन्द्व** इत्यस्य सोपीत्यर्थः, **पूर्वसिद्धस्त्विति** वार्तिकोक्तेः तदभावकल्पने मानाभावात् ॥

(आक्षेपस्मारणभाष्यम्)

ननु चोक्तम्—*एकादीनां दशादिभिर्द्वन्द्व इति चेद्विंशत्यादिषु वचनप्रसङ्गः* इति ॥

(समाधानभाष्यम्)

नैष दोषः । सर्वो हि द्वन्द्वो विभाषैकवद्भवति ॥

(प्रदीपः) **सर्वो हीति** । **तिष्यपुनर्वस्वोरित्यत्र** बहुवचनग्रहणेनैतज्ज्ञापितम् ॥

(उद्द्योतः) **तिष्यपुनर्वस्वोरिति** । एकविंशत्यादावितरेतरयोगस्तु न, अनभिधानादिति बोध्यम् । द्वन्द्वतत्पुरुषाभ्यां स्वरभेदस्त्वप्यत एवेति केचित् ॥ परे तु तत्पुरुषत्वे स्वरो न सिध्यती-

त्याशङ्कास्तु तर्हि द्वन्द्व इति भाष्योक्तेः स्वरभेदो नेष्टः । उपक्रमे कोयं समासः ? द्वन्द्व इति सिद्धान्त्युक्तेरत्र द्वन्द्व एवेत्येवार्थः । सिद्धं त्विति तु सिद्धान्त्येकदेश्युक्तिरित्याहुः ॥ २९ ॥

(आक्षेपभाष्यम्)

यदा तर्ह्येकवचनं तदा नपुंसकलिङ्गं प्राप्नोति ॥

(समाधानभाष्यम्)

लिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्य ॥ चार्थे ॥२९

(प्रदीपः) लिङ्गमशिष्यमिति । सनपुंसकमिति न कर्तव्यमित्यर्थः ॥ २९ ॥

(इति समासप्रकरणम्)

(अथ पूर्वनिपातप्रकरणम्)

(२८८ पूर्वनिपातनियमसूत्रम् ॥ २।२।२ आ. ७ सू.)

४५० उपसर्जनं पूर्वम् ॥ २।२।३० ॥

(सूत्रप्रयोजनाधिकरणम्)

(आक्षेपभाष्यम्)

किमर्थमिदमुच्यते ? ॥

(१४३६ समाधानवार्तिकम् ॥ १ ॥)

॥ * ॥ उपसर्जनस्य पूर्ववचनं परप्रयोगनिवृत्त्यर्थम् ॥ * ॥

(भाष्यम्) उपसर्जनस्य पूर्ववचनं क्रियते । परप्रयोगो मा भूदिति ॥

(प्रदीपः) उपसर्जनम् ॥ ३० ॥ परप्रयोगनिवृत्त्यर्थमिति । वाक्यवत्समासे पदानामनियते प्रयोगे प्राप्ते नियमार्थमेतदित्यर्थः ॥

(१४३७ समाधानबाधकवार्तिकम् ॥ २ ॥)

॥ * ॥ न वानिष्टादर्शनात् ॥ * ॥

(भाष्यम्) न वा एतत्प्रयोजनमस्ति । किं कारणम् ? । अनिष्टादर्शनात् । न हि किंचिदनिष्टं दृश्यते । न हि कश्चिद्राजपुरुष इति प्रयोक्तव्ये पुरुषराज इति प्रयुङ्क्ते । यदि चानिष्टं प्रसज्येत ततो यत्नार्हं स्यात् ॥

(प्रदीपः) न वेति । नित्येषु शब्देषु प्रयोगसंकरे स्थिते ग्राम्यादिप्रयोगनिवारणायेदं शास्त्रम् । इह तु विपर्ययप्रयोगो नैव दृश्यत इति किं तन्निवृत्त्यर्थेन यत्नेनेत्यर्थः ॥

(उद्द्योतः) उपसर्जनं पू० ॥ ३० ॥ विपर्ययप्रयोग इति । पदयोर्विपर्ययेण प्रयोग इत्यर्थः ॥

(आक्षेपभाष्यम्)

अथ यत्र द्वे षष्ठ्यन्ते भवतः कस्मात्तत्र प्रधानस्य पूर्वनिपातो न भवति । राज्ञः पुरुषस्य राजपुरुषस्येति ? ॥

(प्रदीपः) इदानीमारब्धे सूत्रे दोषमुद्भावयति—अथ यत्रेति ॥ राज्ञः पुरुषस्येति । द्वयोरपि षष्ठीति समासशास्त्रे प्रथमानिर्दिष्टत्वादुपसर्जनत्वात् पूर्वनिपातानियमप्रसङ्गः ॥

(उद्द्योतः) सूत्रप्रत्याख्याने उत्तरग्रन्थानुत्थानमाशङ्क्याह— इदानीमिति ॥

(१४३८ समाधानवार्तिकम् ॥ ३ ॥)

॥ * ॥ षष्ठ्यन्तयोः समासेऽर्थाभेदात् प्रधानस्यापूर्वनिपातः ॥ * ॥

(भाष्यम्) षष्ठ्यन्तयोः समासे अर्थाभेदात्प्रधानस्य पूर्वनिपातो न भविष्यति ॥ एवं न चेदमकृतं भवति 'उपसर्जनं पूर्वम्' इति । अर्थश्चाभिन्न इति कृत्वा प्रधानस्य पूर्वनिपातो न भविष्यति ॥ उपसर्जनम् ॥ ३० ॥

(प्रदीपः) अर्थाभेदादिति । उपसर्जनसंज्ञान्वर्थत्वादप्रधानस्यैव भवति पुरुषश्चात्र राजापेक्षया प्रधानमेवेति पुरुषार्थो न भिद्यते राजापेक्षया न व्यतिरिच्यत इत्यर्थः ॥ न चेदमिति । अबुधभ्रान्तिनिराकरणायाश्रितमेवेत्यर्थः ॥ ३०॥

(उद्द्योतः) न भिद्यते इति । वाक्यापेक्षयाऽप्रधानत्वरूपभेदवान्न भवतीत्यर्थः । तदाह—राजापेक्षया न व्यतिरिच्यते इति । व्यतिरेकोऽत्र भेदमूलकसंबन्धः । एवं च राजनिरूपितभेदनिबन्धनसंबन्धवान्न भवतीत्यर्थः । विशेषणनिष्ठ एव संबन्ध इति भावः ॥ परे तु षष्ठी सुबन्तेन समस्यत इत्युक्ते प्रत्यासत्त्या येन सुबन्तेन समासस्तन्निरूपितसंबन्धार्थकषष्ठ्येव गृह्यते इति तदेव षष्ठ्यन्तं प्रथमानिर्दिष्टं, न प्रधानमिति । एवं नार्थात्पूरणगुणेति सूत्रस्थसमानाधिकरणेनेत्यपि प्रत्याख्यातप्रायमेव । समानाधिकरणेन षष्ठीसमासाप्राप्तेः । षष्ठीतिसूत्रे प्रत्यासत्त्याश्रयणात् ॥ अर्थाभेदादिति—भाष्यस्यायमर्थः—अर्थस्य पुरुषस्य राज्ञा भेदाभावाद् राजनिरूपितभेदनिबन्धनसंबन्धत्वाभावात् । किं तु धनादिनिरूपितसंबन्धत्वादिति संबन्धस्य विशेषणनिष्ठत्वादित्याहुः ॥ ये तु—अर्थाभेदादिति अप्रधानपदोपसर्जनपदयोर्विशेष इत्याहुः ॥ तन्न । प्रथमानिर्दिष्टमिति सूत्रस्थभाष्यविरोधात् । अन्यमंबन्धिनिरूपिताप्राधान्यस्यात्रापि सत्त्वाच्च । पूर्वकायासिद्ध्या तयोः पर्यायताया अशक्यस्वीकाराच्च ॥ ३० ॥

(२८९ पूर्वनिपातनियमसूत्रम् ॥ २ । २ । २ आ. ८ सू.)

४५४ अल्पाच्तरम् ॥ २।२।३४ ॥

(तरबर्थविचाराधिकरणम्)

(आक्षेपभाष्यम्)

किमयं तन्त्रं तरनिर्देशः, आहोस्विदतन्त्रम् ? ॥

(प्रदीपः) **अल्पाच्तरम् ॥ ३४ ॥ किमयमिति** । किं तरबर्थः प्रकर्ष आश्रीयते । अथ स्वार्थे अत एव निपातनात्तरः कृत इति प्रश्नः ॥

(उद्द्योतः) अल्पाच् ॥ ३४ ॥ तरपः श्रवणाद्विचारानुपपत्तिमाशङ्क्याह—**किमिति** ॥

(प्रत्याक्षेपभाष्यम्)

किं चातः ? ॥

(प्रथमपक्षे दूषणभाष्यम्)

यदि तन्त्रम्, द्वयोर्नियमः बहुष्वनियमः ॥ तत्र को दोषः ? । शङ्खदुन्दुभिवीणानामिति न सिध्यति । दुन्दुभिशब्दस्यापि पूर्वनिपातः प्राप्नोति ॥

(प्रदीपः) **द्वयोरिति** । प्लक्षन्यग्रोधावित्यादावेव स्याद् न्यग्रोधशब्दस्याल्पाच्त्वात् तदपेक्षया प्लक्षशब्दस्याल्पाच्तरत्वात् । बहुषु तु सन्निहितेषु द्विवचनोपपदत्वाभावात्तरपोनुत्पत्तिरिति तत्रानियमप्रसङ्गः । ततश्च शङ्खदुन्दुभिवीणानामित्यत्र दुन्दुभिशब्दस्यापि कदाचित्पूर्वनिपातः स्यात् ॥

(उद्द्योतः) तन्त्रे तरनिर्देशे प्लक्षन्यग्रोधावित्यादिसिद्ध्यर्थं यत्किंचिदपेक्षयाऽल्पाच्त्वम् । अतिशयस्तूपात्तापेक्षया, अतन्त्रे त्वल्पत्वमेवोपात्तापेक्षयेति बोध्यम् । अत एव शङ्खदुन्दुभिवीणानामित्यस्य सिद्धिस्तत्पक्षे ॥ तत्रान्त्यो युक्तः । द्वयोरित्यस्याविवक्षावदतिशयस्याप्यविवक्षैवेत्यादित्याहुः ॥ भाष्ये—**दुन्दुभिशब्दस्यापीति** । न चैतत्प्रवृत्त्यभावेपि द्वन्द्वे घीत्यस्य प्रवृत्त्या दुन्दुभिशब्दस्यैव पूर्वनिपातः प्राप्नोतीत्यपिरसंगत इति वाच्यम् । पूर्वयोः पूर्वं द्वन्द्वे ततो वीणाशब्देन द्वन्द्वे तस्य पूर्वनिपाताप्राप्त्या तदुक्तेः ॥ तद्ध्वनयन्नाह—**कदाचिदिति** ॥

(द्वितीयपक्षे दूषणभाष्यम्)

अथातन्त्रम्, 'मृदङ्गशङ्खतूणवाः पृथङ् नदन्ति संसदि' 'प्रासादे धनपतिरामकेशवानाम्' इत्येतन्न सिध्यति ॥

(प्रदीपः) अतन्त्रे तरपि दुन्दुभिशब्दापेक्षयाल्पाच्त्वसद्भावाच्छङ्खवीणाशब्दयोरन्यतरस्य पूर्वनिपातो भवति न दुन्दुभिशब्दस्येति दोषाभावः । **मृदङ्गशङ्खतूणवा इति** । शङ्खशब्दस्याल्पाच्त्वात्पूर्वनिपातः प्राप्नोति । तन्त्रे तु तरपि पूर्वोक्तेन न्यायेन बहुष्वनियमादेतद्रूपं सिध्यति ॥

(उद्द्योतः) अथातन्त्रमितिभाष्याशयमाह—**अतन्त्रे इति** । **अल्पाच्त्वेति** । परत्वादस्यैव प्रवृत्तेरिति भावः ॥ **मृदङ्गशङ्खतूणवा** इति पक्षद्वयेपि भाष्योक्तरीत्यैव साध्यम् । अतन्त्रपक्षे त्वारोपितातिशये तरप्पारायणे दृष्टार्थः ॥ **स्वरितादिति** सूत्रेऽनुदात्तानामिति बहुवचननिर्देशवत् ॥ तन्त्रे तरनिर्देशे बहुषु नियमाय भाष्ये उक्तमल्पाजिति **वक्ष्यामीति** । यतः कुतश्चित्सर्वस्याप्यल्पाच्त्वात्सामर्थ्यादतिशयप्रतीतिः । एवं च द्वयोरित्यंशाभावात् शङ्खदुन्दुभीत्यादिसिद्धिः । एवं च द्वयोरित्यंशत्यागपूर्वकमतिशयो विवक्षित इति तात्पर्यम् ॥ मृदङ्गेत्यादौ त्रयाणां समासे तु शङ्खस्यैव पूर्वनिपात इति बोध्यमिति परे ॥

(प्रथमपक्षाङ्गीकारभाष्यम्)

यथेच्छसि तथाऽस्तु । अस्तु तावत्तन्त्रम् ॥

(आक्षेपस्मारणभाष्यम्)

ननु चोक्तम्—'द्वयोर्नियमो बहुष्वनियमः' इति । तत्र शङ्खदुन्दुभिवीणानामिति न सिध्यति । दुन्दुभिशब्दस्यापि पूर्वनिपातः प्राप्नोति—इति ॥

(समाधानभाष्यम्)

नैष दोषः । यदेतद् "अल्पाच्तरम्" इति, तद् "अल्पाज्" इति वक्ष्यामीति ॥

(प्रदीपः) **यदेतदिति** । तन्त्रे दोषप्रसङ्गात् प्रयोजनाभावाच्च तरनिर्देशो न कर्तव्य इत्यर्थः ॥

(द्वितीयपक्षाभ्युपगमभाष्यम्)

अथ वा पुनरस्त्वतन्त्रम् ॥

(आक्षेपस्मारणभाष्यम्)

ननु चोक्तम्—'मृदङ्गशङ्खतूणवाः पृथङ् नदन्ति संसदि' 'प्रासादे धनपतिरामकेशवानाम्' इत्येतन्न सिध्यति—इति ॥

(१४३९ समाधानवार्तिकम् ॥ १ ॥)

॥ * ॥ अतन्त्रे तरनिर्देशे शङ्खतूणवयोर्मृदङ्गेन समासः ॥ * ॥

(भाष्यम्) **अतन्त्रे तरनिर्देशे शङ्खतूणवयोर्मृदङ्गेन सह समासः करिष्यते । शङ्खश्च तूणवश्च शङ्खतूणवौ । शङ्खतूणवौ च मृदङ्गश्च मृदङ्गशङ्खतूणवाः । रामश्च केशवश्च रामकेशवौ । रामकेशवौ च धनपतिश्च धनपतिरामकेशवाः धनपतिरामकेशवानामिति ॥**

(प्रदीपः) अतन्त्रे तु तरस्तस्य स्वार्थिकत्वज्ञापनमेव तरनिर्देशस्य प्रयोजनम् ॥ **शङ्खतूणवाविति** । नियतद्रव्यविवक्षायां जातिपरत्वाभावादेकवद्भावाभावः । तूर्याङ्गाणामित्यपि न भवति । शङ्खस्यातूर्याङ्गत्वादित्येके ॥ तूर्यशिल्पोपजीविन एव तूर्याङ्गत्वेन गृह्यन्ते । तेषां हि मुख्यं तूर्याङ्गत्वमित्यपरे ॥

(उद्द्योतः) **नियतद्रव्येति** । जातिप्राधान्ये हि तदाश्रयसर्वव्यक्तीनां विनिगमनाविरहेण नान्तरीयकत्वाद्बोध इति भावः ॥

(बहूनां प्राप्तौ नियमाधिकरणम्)

(आक्षेपभाष्यम्)

अथ यत्र बहूनां पूर्वनिपातप्रसङ्गः किं तत्रैकस्य नियमो भवति । आहोस्विदविशेषेण ॥

(प्रदीपः) **अथ यत्रेति** । यदि जातिपदार्थपक्ष आश्रीयते तदा लक्षणाऽऽश्रयभावादेकस्यैव नियमे सति शेषा-

णामनियमेन भाव्यम्। अथ व्यक्तिपक्षस्तदा पुनःपुनर्लक्षणप्रवर्तनात् सर्वेषां नियमेन भाव्यमिति मत्वा पृच्छति ॥

(उद्द्योतः) तदा लक्षणेति। एतदुदाहरणावच्छिन्नघित्वजात्यवच्छिन्ने क्वचित्प्रवृत्त्या चरितार्थत्वाद्, एकस्य युगपदवध्यवधिमद्भावासंभवाच्च, अन्त्यस्यावधित्वेप्येकस्य व्यवधानाच्च पुनस्तत्रैवाप्रवृत्तेरिति भावः ॥ व्यक्तिपक्ष इति। एतदुदाहरणावच्छिन्नतत्तद्घित्वव्यक्तिविषयकलक्षणभेदेन तेषामचारितार्थ्यात्पुनःपुनः प्रवृत्तिरस्त्येवेति भावः ॥ वस्तुतो वाचनिकमेवेदं जातिपक्षेप्यावृत्तिं विनैव तज्जात्याश्रयसर्वविषयकत्वासंभवात् ॥

(१४४० समाधानवार्तिकम् ॥ २ ॥)

॥ * ॥ अनेकप्राप्तावेकस्य नियमोऽनियमः शेषेषु ॥ * ॥

(भाष्यम्) अनेकस्य प्राप्तावेकस्य नियमो भवति, शेषेष्वनियमः। पटुमृदुशुक्लाः। पटुशुक्लमृदव इति ॥

(प्रदीपः) उत्तरं तु लक्ष्यदर्शनवशाज्जातिपक्षाश्रयेण ॥

(न्यूनतापूर्त्यधिकरणम्)

(१४४१ पूर्वनिपातवार्तिकम् ॥ ३ ॥)

॥ * ॥ ऋतुनक्षत्राणामानुपूर्व्येण समानाक्षराणाम् ॥ * ॥

(भाष्यम्) ऋतुनक्षत्राणामानुपूर्व्येण समानाक्षराणां पूर्वनिपातो वक्तव्यः। शिशिरवसन्तावुदगयनस्थौ। कृत्तिकारोहिण्यः ॥

(प्रदीपः) उदगयनस्थाविति। उत्तरायणस्थौ। लौकिकप्रयोगप्रदर्शनपरमिदम् ॥

(उद्द्योतः) उदगयनस्थावित्यस्यानुपयोगादाह—लौकिकेति ॥

(१४४२ पूर्वनिपातवार्तिकम् ॥ ४ ॥)

॥ * ॥ अभ्यर्हितम् ॥ * ॥

(भाष्यम्) अभ्यर्हितं च पूर्वं निपततीति वक्तव्यम्। मातापितरौ। श्रद्धामेधे ॥

(प्रदीपः) मातापितराविति। गर्भधारणादिना पित्रपेक्षया माताभ्यर्हिता ॥ श्रद्धामेधे इति। सत्यां श्रद्धायामर्थक्रियाकारिणी मेधेति श्रद्धाया अभ्यर्हितत्वम् ॥

(१४४३ पूर्वनिपातवार्तिकम् ॥ ५ ॥)

॥ * ॥ लघ्वक्षरम् ॥ * ॥

(भाष्यम्) लघ्वक्षरं पूर्वं निपततीति वक्तव्यम्। कुशकाशम्। शरचापम् ॥

(आचार्यान्तरमतप्रदर्शकभाष्यम्)

अपर आह—

सर्वत एवाभ्यर्हितं पूर्वं निपततीति वक्तव्यम्। लघ्वक्षरादपीति ॥ दीक्षातपसी श्रद्धातपसी ॥

(प्रदीपः) लघ्वक्षरादपीति। पूर्वविप्रतिषेधेन ॥ दीक्षातपसी इति। दीक्षार्थं तपश्चरणमिति दीक्षाया अभ्यर्हितत्वं स्वरूपेण वा ॥

(१४४४ पूर्वनिपातवार्तिकम् ॥ ६ ॥)

॥ * ॥ वर्णानामानुपूर्व्येण ॥ * ॥

(भाष्यम्) वर्णानामानुपूर्व्येण पूर्वनिपातो भवतीति वक्तव्यम्। ब्राह्मणक्षत्रियविट्शूद्राः ॥

(प्रदीपः) वर्णानामिति। वेददर्शनाश्रयणोत्पत्तिक्रमेण वर्णानामानुपूर्व्यम् ॥

(उद्द्योतः) वेददर्शनेति। ब्राह्मणोस्य मुखमासीदित्यादिवेददर्शनम्।

(१४४५ पूर्वनिपातवार्तिकम् ॥ ७ ॥)

॥ * ॥ भ्रातुश्च ज्यायसः ॥ * ॥

(भाष्यम्) भ्रातुश्च ज्यायसः पूर्वनिपातो भवतीति वक्तव्यम्। युधिष्ठिरार्जुनौ ॥

(१४४६ पूर्वनिपातवार्तिकम् ॥ ८ ॥)

॥ * ॥ संख्याया अल्पीयसः ॥ * ॥

(भाष्यम्) संख्याया अल्पीयसः पूर्वनिपातो भवतीति वक्तव्यम्। एकादश द्वादश ॥

(प्रदीपः) अल्पीयस इति। अर्थस्य वाचिकाया इति शेषः। एतच्च द्वन्द्वाद्वन्द्वविषयमित्याहुः ॥ द्व्येकयोरिति तु सौत्रो निर्देशः ॥ ३४ ॥

(उद्द्योतः) अल्पीयस्या इत्युचितमत आह—अर्थस्येति ॥ एतच्चेति। अत एव तत्पुरुषेप्येकादशेत्येव बहुव्रीहौ द्वित्रा इत्यादिसिद्धिश्चेत्याहुः ॥ ३४ ॥

(१४४७ पूर्वनिपातवार्तिकम् ॥ १ ॥)

॥ * ॥ धर्मादिषूभयम् ॥ * ॥

(भाष्यम्) धर्मादिषूभयं पूर्वं निपततीति वक्तव्यम्। धर्मार्थौ अर्थधर्मौ। कामार्थौ अर्थकामौ। गुणवृद्धी वृद्धिगुणौ। आद्यन्तौ अन्तादी ॥ अल्पाच्तरम् ॥ ३४ ॥

(२९० पूर्वनिपातनियमसूत्रम् ॥ २। २। २ आ. ९ सू.)

४५५ सप्तमीविशेषणे बहुव्रीहौ ॥ २।२।३५ ॥

(न्यूनतापूरणाधिकरणम्)

(१४४८ पूर्वनिपातवार्तिकम् ॥ २ ॥)

॥ * ॥ बहुव्रीहौ सर्वनामसंख्ययोरुपसंख्यानम् ॥ * ॥

(भाष्यम्) बहुव्रीहौ सर्वनामसंख्ययोरुपसं-

ख्यानं कर्तव्यम् ॥ विश्वदेवः । विश्वयशाः । द्विपुत्रः । द्विभार्यः ॥

(प्रदीपः) सप्तमी ॥ ३५ ॥ विश्वदेव इति । यदा विश्वस्य विशेष्यत्वं तदेदमुदाहरणम् । विशेषणत्वे तु सूत्रेणैव सिद्धः पूर्वनिपातः ॥ द्विपुत्र इति । दिक्प्रदर्शनमेतद् ॥ अत्र हि विशेषणत्वादेव सिद्धः संख्यायाः पूर्वनिपातः । तस्माद्द्विशुक्ल इत्याद्युदाहरणम् ॥

(उद्द्योतः) सप्तमी ॥ ३५ ॥ यदा विश्वस्येति । देव इत्युपक्रमे तस्य तत्त्वसंभवः । विश्वं देवो यस्येति विग्रहः । न संज्ञायामिति कन्निषेधः ॥ द्विशुक्लइति । द्वौ शुक्लगुणौ यस्येत्यर्थः । अत्र हि द्वयोर्गुणवाचित्वादनियमो विशेषणत्वस्य ॥ पुत्रभार्याशब्दावपि गुणवचनाविति भाष्याशयः । जन्यपुंस्त्वधर्मभोग्यस्त्रीत्वयोर्गुणत्वादित्यन्ये ॥ ३५ ॥

(आक्षेपभाष्यम्)

अथ यत्र संख्यासर्वनाम्नोरेव बहुव्रीहिः कस्य तत्र पूर्वनिपातेन भवितव्यम्? ॥

(समाधानभाष्यम्)

परत्वात्संख्यायाः—द्व्यन्याय त्र्यन्याय ॥

(प्रदीपः) परत्वात् संख्याया इति । शब्दपरविप्रतिषेधात् । एवमर्थमेव च संख्यासर्वनाम्नोरिति न कृतम् ॥ ३५ ॥

(१४४९ पूर्वनिपातवार्तिकम् ॥ ३ ॥)

॥ * ॥ वा प्रियस्य ॥ * ॥

(भाष्यम्) वा प्रियस्य पूर्वनिपातो भवतीति वक्तव्यम् । प्रियगुडः गुडप्रियः ॥

(१४५० पूर्वनिपातबाधकवार्तिकम् ॥ ४ ॥)

॥ * ॥ सप्तम्याः पूर्वनिपाते गड्वादिभ्यः परवचनम् ॥ * ॥

(भाष्यम्) सप्तम्याः पूर्वनिपाते गड्वादिभ्यः परा सप्तमी भवतीति वक्तव्यम् । गडुकण्ठः गडुशिराः ॥ सप्तमीवि० ॥ ३५ ॥

(२९१ पूर्वनिपातनियमसूत्रम् ॥ २ । २ । २ आ. १०)

४५६ निष्ठा ॥ २।२।३६ ॥

(पूर्वनिपातबाधकाधिकरणम्)

(१४५१ परनिपातवार्तिकम् ॥ १ ॥)

॥ * ॥ निष्ठायाः पूर्वनिपाते जातिकालसुखादिभ्यः परवचनम् ॥ * ॥

(भाष्यम्) निष्ठायाः पूर्वनिपाते जातिकालसुखादिभ्यः परा निष्ठा भवतीति वक्तव्यम् । शार्ङ्गजग्धी । पलाण्डुभक्षिती । मासजाता । संवत्सरजाता । सुखजाता । दुःखजाता ॥

(१४५२ प्रत्याख्यानवार्तिकम् ॥ २ ॥)

॥ * ॥ न वोत्तरपदस्यान्तोदात्तवचनं ज्ञापकं परभावस्य ॥ * ॥

(भाष्यम्) न वा वक्तव्यम् । किं कारणम्? । उत्तरपदस्यान्तोदात्तवचनं ज्ञापकं परभावस्य । यदयं जातिकालसुखादिभ्यः परस्या निष्ठाया उत्तरपदस्यान्तोदात्तत्वं शास्ति तज्ज्ञापयत्याचार्यः—परात्र निष्ठा भवतीति ॥

(उद्द्योतः) निष्ठा ॥ ३६ ॥ यदयमिति । भाष्ये । बहुव्रीहौ आच्छादनभिन्नजात्यादिभ्यः परमुत्तरपदं क्तान्तमन्तोदात्तं कृतादीन्वर्जयित्वेति सूत्रार्थः ॥ ३६ ॥

(१४५३ आक्षेपवार्तिकम् ॥ ३ ॥)

॥ * ॥ प्रतिषेधे तु पूर्वनिपातप्रसङ्गस्तस्माद्राजदन्तादिषु पाठः ॥ * ॥

(भाष्यम्) प्रतिषेधे तु पूर्वनिपातः प्राप्नोति 'अकृतमितप्रतिपन्नाः' इति, तस्माद्राजदन्तादिषु पाठः कर्तव्यः ॥

(प्रदीपः) निष्ठा ॥ ३६ ॥ प्रतिषेधे त्विति । अकृतमितप्रतिपन्ना इति कृतादीनामन्तोदात्तत्वप्रतिषेधादन्तोदात्तविधानाज्ज्ञापितः परनिपातोपि न स्यादित्यर्थः ॥

(१४५४ पाठकर्तव्यता प्रत्याख्यानवार्तिकम् ॥ ४ ॥)

॥ * ॥ नवा प्रतिषेधवचनं ज्ञापकं परभावस्य ॥ * ॥

(भाष्यम्) न वा कर्तव्यः । अत्रापि प्रतिषेधवचनं ज्ञापकम्—परा निष्ठाभवतीति ॥

(प्रदीपः) नवेति । उत्तरपदान्तोदात्तत्वे प्रसक्ते प्रतिषेधः क्रियते । यदि च परनिपातस्ततस्तत्प्रसङ्गो नान्यथा ॥ ३६ ॥

(१४५५ परनिपातवार्तिकम् ॥ ५ ॥)

॥ * ॥ प्रहरणार्थेभ्यश्च ॥ * ॥

(भाष्यम्) प्रहरणार्थेभ्यश्च परे निष्ठा सप्तम्यौ भवत इति वक्तव्यम् । अस्युद्यतः मुसलोद्यतः असिपाणिः दण्डपाणिः ॥

(विप्रतिषेधाधिकरणम्)

(१४५६ द्वन्द्वे घिसूत्रादजाद्यदन्तसूत्रबलवत्त्ववार्तिकम् ॥ ६ ॥)

॥ * ॥ द्वन्द्वे घ्यजाद्यदन्तं विप्रतिषेधेन ॥ * ॥

(भाष्यम्) "द्वन्द्वे घि" इत्यस्मात् "अजाद्यदन्तम्" इत्येतद्भवति विप्रतिषेधेन । 'द्वन्द्वे घि' इत्यस्माद-

काशः—पटुगुप्तौ । 'अजाद्यदन्तम्' इत्यस्यावकाशः—उष्ट्रखरौ । इहोभयं प्राप्नोति—इन्द्राग्नी । 'अजाद्यदन्तम्' इत्येतद् भवति विप्रतिषेधेन ॥

(१४५७ द्वन्द्वेघिसूत्राजाद्यदन्तसूत्राभ्यामल्पाच्तरसूत्रबलीयस्त्ववार्तिकम् ॥ ७)

॥ * ॥ उभाभ्यामल्पाच्तरम् ॥ * ॥

(भाष्यम्) उभाभ्याम् "अल्पाच्तरम्" इत्येतद्भवति विप्रतिषेधेन । 'द्वन्द्वे घि' इत्यस्यावकाशः—पटुगुप्तौ । 'अल्पाच्तरम्' इत्यस्यावकाशः—वाग्दृषदौ । इहोभयं प्राप्नोति—वागग्नी । 'अल्पाच्तरम्' इत्येतद्भवति विप्रतिषेधेन ॥

'अजाद्यदन्तम्' इत्यस्यावकाशः—उष्ट्रखरौ । 'अल्पाच्तरम्' इत्यस्यावकाशः—वाग्दृषदौ । इहोभयं प्राप्नोति—वागिन्द्रौ । 'अल्पाच्तरम्' इत्येतद्भवति विप्रतिषेधेन ॥ निष्ठा ॥ ३६ ॥

(२९२ पूर्वनिपातसूत्रम् ॥ २ । २ । २ आ. ११ सू.)

४५८ कडाराः कर्मधारये ॥ २।२।३८ ॥

(बहुवचनस्यार्थकल्पनाधिकरणम्)

(१४५८ वार्तिकम् ८)

॥ * ॥ कडारादयः ॥ * ॥

(भाष्यम्) कडारादय इति वक्तव्यम् । इहापि यथा स्यात्—गडुलशाण्डिल्यः शाण्डिल्यगडुलः । खण्डवात्स्यः । वात्स्यखण्डः ॥

(आक्षेपभाष्यम्)

तत्तर्हि वक्तव्यम् ? ॥

(समाधानभाष्यम्)

न वक्तव्यम् । बहुवचननिर्देशात् कडारादय इति विज्ञास्यते ॥ कडाराः ॥ ३८ ॥

इति श्रीमद्भगवत्पतञ्जलिविरचिते द्वितीयस्याध्यायस्य द्वितीये पादे द्वितीयमाह्निकम् ॥ पादश्च समाप्तः ॥

(प्रदीपः) कडाराः ॥ ३८ ॥ बहुवचननिर्देशादिति । कडारशब्दस्यैकत्वादेकवचने कर्तव्ये साहचर्यादारोपितकडाररूपगडुलादिशब्दगतबहुत्वापेक्षो बहुवचननिर्देशो यथा छत्रिणो यान्तीति ॥ ३८ ॥

इत्युपाध्यायजैयटपुत्रकैयटकृते महाभाष्यप्रदीपे द्वितीयस्याध्यायस्य द्वितीये पादे द्वितीयमाह्निकम् ॥
द्वितीयपादः समाप्तः ॥

(उद्द्योतः) कडाराः ॥ ३८ ॥ कडारशब्दस्येति । बहुवचनसामर्थ्यादजहल्लक्षणा छत्रिण इतिवदाश्रयणीयेत्यर्थः ॥ ३८ ॥

इति शिवभट्टसुतसतीगर्भजनागेशभट्टविरचिते भाष्यप्रदीपोद्द्योते द्वितीयाध्यायस्य द्वितीये पादे द्वितीयमाह्निकम् ॥
पादश्च समाप्तः ॥

द्वितीयाध्यायस्य तृतीयपादे

प्रथममाह्निकम् ॥

(अथ विभक्त्यर्थप्रकरणम्)

(२९३ अधिकारसूत्रम् ॥ २।३।१ आ. १)

४५९ अनभिहिते ॥ २।३।१ ॥

(अनभिहितशब्दार्थनिरूपणाधिकरणम्)

(आक्षेपभाष्यम्)

अनभिहित इत्युच्यते। किमिदमनभिहितं नाम?॥

(प्रदीपः) **अनभिहिते** ॥१॥ प्रत्याख्यानवादी स्ववाचानभिहितशब्दार्थमारम्भवादिनं संजल्पयितुं पृच्छति—**किमिदमिति**। अभिपूर्वस्तावद्धातिर्बन्धनोच्चारणप्रतिपादनेषु वर्तते। **अश्वाभिधानीमादत्त** इत्यत्र बन्धनवृत्तिः। **अभिहितः श्लोक** इत्युच्चारणवृत्तिः। **अभिहितोर्थ** इति प्रतिपादनवृत्तिः। हिनोतेरपि गतिवृद्ध्यर्थस्याभिहितमिति भवति तत्र वक्ष्यमाणानां कर्मादीनामर्थानां बन्धनाद्यर्थचतुष्टयासंभवात् प्रतिपादनवचन एवाभिहितशब्द आश्रयणीयस्ततः प्रयोजनाभावादनर्थकं सूत्रमिति भावः ॥

(उद्द्योतः) अनभिहिते ॥१॥ **स्ववाचेति** ॥ प्रयोजककर्त्र्येत्यर्थः। करणभूतयेत्यर्थो वा। **स्वशब्देनारम्भवादी** ॥ स्वरूपार्थयोः प्रसिद्धत्वेपि तस्यानेकार्थत्वात्सिद्धान्त्यभिमतमर्थं तन्मुखेन वाचयित्वा सूत्रं प्रत्याख्यातुं प्रश्न इति भावः ॥ **अर्थचतुष्टयासंभवादिति**। तद्विषयत्वासंभवादित्यर्थः ॥

(समाधानभाष्यम्)

'उक्तम्, निर्दिष्टम्, अभिहितम्'इत्यनर्थान्तरम् ॥ यावद् ब्रूयाद्—'अनुक्ते, अनिर्दिष्टे' इति, तावद् 'अनभिहिते' इति ॥

(प्रदीपः) पूर्वोक्तेनाभिप्रायेणाह—**उक्तमिति**। प्रतिपादितमित्यर्थः ॥ यथा **उक्तार्थानामप्रयोग** इति ॥ **यावद्ब्रूयादिति** यावत्तावच्छब्दौ निपातावभिन्नार्थत्वं प्रतिपादयतः ॥

(सूत्रप्रयोजनाधिकरणम्)

(१४५९ प्रत्याख्यानवार्तिकम् ॥ १ ॥)

॥ * ॥ अनभिहितवचनमनर्थकमन्यत्रापि विहितस्याभावादभिहिते ॥ * ॥

(भाष्यम्) **अनभिहितवचनमनर्थकम् ॥ किं कारणम्?। अन्यत्रापि विहितस्याभावादभिहिते। अन्यत्राप्यभिहिते विहितं न भवति ॥ क्वान्यत्र?। चित्रगुः, शबलगुः, बहुव्रीहिणोक्तत्वान्मत्वर्थस्य मत्वर्थीयो न भवति। गर्गाः, वत्साः, बिदाः, उर्वाः, यञञ्भ्यामुक्तत्वादपत्यार्थस्य न्याय्योत्पत्तिर्न भवति। सप्तपर्णोऽष्टापद इति समासेनोक्तत्वाद्वीप्साया द्विर्वचनं न भवतीति ॥**

(प्रदीपः) **अनभिहितवचनमिति**। अर्थप्रत्यायनाय लोके शब्दः प्रयुज्यते स चार्थो यदा शब्दान्तरेण प्रतिपादितो भवति तदा प्रयोजनाभावाच्छब्दान्तरस्य प्रयोगेण न भाव्यम्। अक्षिनिकोचादिभिरप्यवगतेर्थे शब्दो न प्रयुज्यते, किं पुनः शब्दान्तरप्रतिपादितेर्थे ॥ **यञञ्भ्यामिति**। यञन्तेनाञन्तेन चेत्यर्थः। यञञोस्तु लुप्तत्वादर्थाभिधानं न संभवति ॥ **न्याय्योत्पत्तिरिति**। उत्सर्गः पूर्वाचार्यप्रसिद्ध्या **न्याय्य** उच्यते। बहुवचनोदाहरणम्—गार्ग्यौ गार्ग्याविल्यत्र यञैव परदेशस्यावष्टब्धत्वादण उत्पत्त्यभावात्। बहुवचने तु यञञोर्लुप्तत्वाद्विरोधकाभावादुक्तार्थाश्रयेणैवाणोनुत्पत्तिः प्रतिपाद्या ॥ **सप्तपर्ण इति**। वीप्सायां विषये द्विर्वचनमुच्यते। अस्ति चेह वीप्सा सप्त सप्त पर्णान्यस्येति। समासेन तु शब्दशक्तिस्वाभाव्याद्वीप्साया गमितत्वाद् द्विर्वचनाभावः ॥

(उद्द्योतः) भाष्ये—**विहितस्याभावादभिहिते इति**। लौकिके प्रयोगे लाघवानादरेण भवत्येव तथा प्रयोगो विहितस्य तु नेत्याशयेन ॥ तदुक्तम्—**न संभवतीति**। ताभ्यामिति शेषः ॥ कस्यापि तद्धितस्यान्यायेनोत्पत्त्यसंभवाद् व्यर्थं विशेषणमत आह—**उत्सर्ग इति** ॥ **विरोधकाभावादिति**। परदेशरोधकाभावादित्यर्थः ॥ **अणइति**। इदमुपलक्षणमिञ इति बोध्यम् ॥ सप्तपर्णशब्दे समासे द्वित्वाभावात्कथं वीप्सावगतिस्तत्राह—**समासेनत्विति**।

(प्रथमदृष्टान्तनिरसनभाष्यम्)

यत्तावदुच्यते—चित्रगुः शबलगुरिति बहुव्रीहिणोक्तत्वान्मत्वर्थस्य मत्वर्थीयो न भवतीति ॥ अस्तिसामानाधिकरण्ये मतुब्विधीयते। न चात्रास्तिना सामानाधिकरण्यम् ॥

(प्रदीपः) आरम्भवादी दृष्टान्तेष्वन्यथा साध्यसिद्धिं प्रतिपादयितुमाह—**यत्तावदिति** ॥ **न चात्रास्तिनेति**। वर्तिपदयोरन्यपदार्थ उपसंक्रान्तत्वादस्त्यर्थस्य तत्रैवान्तर्भूतत्वात् स्वार्थस्य संसृष्टत्वादस्तिसामानाधिकरण्याभावः ॥ यदा त्वन्यपदार्थेन तद्वत्ता प्रतिपिपादयिषिता तदा चित्रगुमानिति भवत्येव ॥

(**उद्द्योतः**) ननु सर्वथोक्तार्थानामप्रयोग इति न्याये सति सूत्रारम्भानुपपादनात्किं यत्तावदिति ग्रन्थेनात आह—**आरम्भवादीति**। तथा च तन्न्याये फलाभावेन तन्न्यायसत्त्वे न मानमित्यभिमानः ॥ भाष्ये—**नचात्रास्तिनेति**। वर्तिपदार्थानामन्यपदार्थेन संसृष्टत्वात्पृथक्त्वाभावेन बहिर्भूतास्तिसामानाधिकरण्या-

भाव इति भावः ॥ यत्तु कैयटेनान्यपदार्थस्य तत्रैवान्यपदार्थे एवान्तर्भूतत्वादित्युक्तम्, तदनुपयुक्तम्, बहुव्रीहावस्त्यर्थानन्तर्भावस्य मतुप्सूत्रे भाष्ये उक्तत्वात् । तत्र हि—तद्धितार्थद्विग्वपेक्षया पञ्चगुरित्यादौ बहुव्रीहिरन्तरङ्गत्वमुक्तम्—'विशिष्टस्य षष्ठ्यर्थस्य तद्धितार्थत्वादस्त्यर्थोपचयापेक्ष्यो द्विगुना । षष्ठ्यर्थमात्रापेक्षस्तु बहुव्रीहिः' इति कैयटः॥ **स्वार्थस्यसंसृष्टत्वादिति** । अन्यपदार्थेनेति शेषः । **स्वार्थो** वृत्तिपदार्थः । अत्रोपसंक्रान्तत्वं हेतुः । तच्च नियमेन विशेषणत्वम् ॥

(द्वितीयदृष्टान्तनिरसनभाष्यम्)

यदप्युच्यते—गर्गा वत्सा बिदा उर्वा इति यञञ्भ्यामुक्तत्वादपत्यार्थस्य न्याय्योत्पत्तिर्न भवतीति ॥ "समर्थानां प्रथमाद्वा" इति वर्तते । न चैतत्समर्थानां प्रथमम् । किं तर्हि ? । द्वितीयमर्थमुपसंक्रान्तम् ॥

(प्रदीपः) **न चैतदिति । समर्थानां प्रथमादि**त्यधिकारादपत्यवद्वाचिनः षष्ठ्यन्तात् प्रत्ययेन भाव्यं न त्वपत्यवाचिनः । यञञोस्तु लुकि कृते प्रकृतिरेवापत्यार्थाभिधायिनीति अण् न भवतीत्यर्थः ॥

(उद्द्योतः) भाष्ये **द्वितीयमर्थमुपसंक्रान्तमि**त्यस्य तस्यापत्यमितिसूत्रस्थद्वितीयपदवाच्यमर्थमित्यर्थ इत्याशयेनाह—**समर्थानामिति** ॥

(तृतीयदृष्टान्तनिरसनभाष्यम्)

यदप्युच्यते—सप्तपर्णोऽष्टापद इति समासेनोक्तत्वाद् वीप्सायां द्विर्वचनं न भवतीति ॥ यदत्र वीप्सायुक्तं नादः प्रयुज्यते ॥ किं पुनस्तत् ? । पर्वणि पर्वणि सप्त पर्णान्यस्य । पङ्क्तौ पङ्क्तावष्टौ पदानीति ॥

(प्रदीपः) **यदत्रेति** । वीप्स्यमानार्थाभिधायिनः पदस्य द्विर्वचनं विधीयते । पर्वार्थस्य वीप्सायोगः, न चात्र पर्वशब्दस्य प्रयोगः ॥

(उद्द्योतः) **नचात्रेति** । सप्तपर्णशब्दस्तु तादृशे वृक्षविशेषे रूढ इति भावः ॥ भाष्ये—**पङ्क्तौ पङ्क्ताविति** । अष्टापदं शारिफलमित्यमरः ॥

(दृष्टान्तान्तरभाष्यम्)

श्नम्बहुजकच्सु तर्हि । श्नम्—भिनत्ति छिनत्ति । श्नमोक्तत्वात्कर्तृत्वस्य कर्तरि शब् न भवति ॥ बहुच्—बहुकृतं बहुभिन्नमिति बहुचोक्तत्वादीषदसमाप्तेः कल्पबादयो न भवन्ति ॥ अकच्—उच्चकैः नीचकैरिति अकचोक्तत्वात्कुत्सादीनां कादयो न भवन्ति ॥

श्नमोक्तत्वादिति । भावकर्मकर्तारो विकरणार्था इति पूर्वाचार्यदर्शनमाश्रित्यैवमुक्तम् ॥

(उद्द्योतः) **पूर्वाचार्येति** । स्वमते तु विकरणा द्योतका इत्यभिमानः । वस्तुतो बहुजकचोरपि द्योतकत्वाद् द्योतकविषयेप्ययं न्यायः । द्योतकविषयेपि एकेन द्योतिते **उक्तार्थाना**मिति न्यायेनापरद्योतकाभाव इति बोध्यम् ॥

(दृष्टान्तबाधकभाष्यम्)

ननु च श्नम्बहुजकचोपवादास्ते अपवादत्वाद्बाधका भविष्यन्ति ॥

(प्रदीपः) अत्राप्यन्यथासिद्धिमाह—**नन्विति** । ततश्चोक्तत्वस्य दृष्टान्ताभावादहेतुत्वम् ॥

(१४६० दृष्टान्तसाधकवार्तिकम् ॥ २ ॥)

॥ * ॥ श्नम्बहुजकच्सु नानादेशत्वाद् उत्सर्गाप्रतिषेधः ॥ * ॥

(व्याख्याभाष्यम्)

समानदेशैरपवादैरुत्सर्गाणां बाधनं भवति । नानादेशत्वान्न प्राप्नोति ॥

(प्रदीपः) **नानादेशत्वादिति** । विरोधो बाधकारणम्, न विशेषविधानमेव । वार्तिककारस्य चेदं दर्शनम् ॥ भाष्यकारस्तु विरोधाभावेपि विशेषविधानमात्रेणैव बाधकत्वमन्यत्रावोचत् । तक्रदानं च दधिदानस्य विरोधाभावेपि लोके बाधकं दृश्यते । तदेवं श्नमादिदृष्टान्तावष्टम्भेन हेतुत्वमुक्तत्वस्य व्यवस्थापितम् ॥

(उद्द्योतः) **भाष्यकारस्त्विति** । येननाप्राप्ते यो विधिरारभ्यते स तस्यापवाद इति लक्षणानुसारेण तक्रकौण्डिन्यन्यायमूलकेन सत्यपि सम्भवे बाधनमिति तद्भावः । तन्मतेऽप्ययं न्याय आवश्यकः । यथोक्तम्—समासेनाभिहितः सुजर्थ इति द्विदशा इत्यादौ सुज्नेति ॥

(सूत्रप्रयोजनकथनाधिकरणम्)

(आरम्भवादिभाष्यम्)

किं पुनरिहाकर्तव्योनभिहिताधिकारः क्रियते । आहोस्विदन्यत्र कर्तव्यो न क्रियते ? ॥

(प्रदीपः) इदानीमारम्भवादी पक्षान्तरमाश्रयिष्यामीति पृच्छति—**किं पुनरिति ॥ आहोस्विदन्यत्रेति** । अपूपौ द्वावित्यभिहितेपि प्रत्ययेन द्वित्वे द्विशब्दस्य प्रयोगदर्शनात् श्नमादिभिरभिहिते शबादिनिवृत्त्यर्थः कर्तव्यः सन्न क्रियत इत्यर्थः ॥

(उद्द्योतः) **इदानीमिति** । दृष्टान्तानामन्यथासिद्धिपरिहारे जात इत्यर्थः ॥

(प्रत्याख्यानवादिभाष्यम्)

इहाकर्तव्यः क्रियते । एष एव हि न्याय्यः—यदभिहिते विहितं न स्यात् ॥

(प्रदीपः) प्रत्याख्यानवाद्याह—**इहाकर्तव्य इति** । अपूपौ द्वावित्यादौ तु गतार्थस्यापि द्विशब्दस्य लोके प्रयोगो दृश्यते । अन्यस्य तु गतार्थस्य प्रयोगाभावः प्रयोजनाभावादेव सिद्धः ॥

(उद्द्योतः) **अन्यस्य त्विति** । शास्त्रविहितस्येत्यर्थः । लौकिके प्रयोगे लाघवानादरादिति भावः । एवमेव व्यतिलुनीत इत्यत्रापि समावेशः । तत्र हि पूर्वमात्मनेपदं ततः स्पष्टं तत्प्रतीतये व्यतिप्रयोगोपि । अपूपावित्यत्र द्विवचनं तु विरुद्धविभक्त्यपेक्षयानुवादकविभक्तेर्न्यायसिद्धत्वात्कृतम् ॥ भाष्ये **विहितं न स्यादिति** । न भवितुमर्हतीत्यर्थः । अर्हे कृत्यतृचश्चेति चादर्हे लिङ् ॥

(१४६१ आरम्भवादिसमाधानवार्तिकम् ॥ ३ ॥)

॥ * ॥ अनभिहितस्तु विभक्त्यर्थस्तस्मादनभिहितवचनम् [अभिहिते हि प्रथमाभावः] ॥ * ॥

(भाष्यम्) **अनभिहितस्तु विभक्त्यर्थः ॥ कः पुनर्विभक्त्यर्थः ? । एकत्वादयो विभक्त्यर्थाः ॥ तेष्वनभिहितेषु[सत्सु]कर्मादयोभिहिता विभक्तीनामुत्पत्तौ निमित्तत्वाय मा भूवन्निति ॥ तस्मादनभिहितवचनम् ॥ तस्मादनभिहिताधिकारः क्रियते ॥ अवश्यं चैतदेवं विज्ञेयम्—एकत्वादयो विभक्त्यर्था इति ॥ अभिहिते हि प्रथमाभावः । यो हि मन्यते—कर्मादयो विभक्त्यर्थाः, तेष्वभिहितेषु सामर्थ्यान्मे विभक्तीनामुत्पत्तिर्न भविष्यतीति । प्रथमा तस्य न प्राप्नोति ॥ क्व ? । वृक्षः प्लक्षः ॥ किं कारणम् ? । प्रातिपदिकेनोक्तः प्रातिपदिकार्थ इति ॥**

(प्रदीपः) इदानीमेकत्वादीनां विभक्त्यर्थत्वमाश्रित्य सूत्रं समर्थयितुमाह—**अनभिहितस्त्विति** । **कर्मणि द्वितीयेत्यादेर्बहुषु बहुवचन**मित्यादिनैकवाक्यता । तत्र यदेकत्वादीनि विशेषणानि कर्मादीनि विशेष्याणि एकस्य यत्कर्म तत्र द्वितीयैकवचनमिति, तदा कर्म द्वितीयार्थः संपद्यते । तच्च यदा कृदादिभिरभिहितं भवति, तदा गतार्थत्वाद् द्वितीयायाः प्राप्तिरेव नास्तीति नार्थोनभिहिताधिकारेण ॥ यदा तु कर्मादीनां विशेषणत्वमेकत्वादीनां विशेष्यत्वं कर्मणो यदेकत्वादि तत्र द्वितीयेति, तदेकत्वादयो विभक्त्यर्थाः संपद्यन्ते । ते चाभिहितेष्वपि कृदादिभिः कर्मादिष्वनभिहिता इति तदभिधानाय द्वितीयादीनां प्रसङ्गे तन्निवारणाय कर्तव्योनभिहिताधिकारः ॥ **कर्मणि द्वितीये**त्यादौ कर्मादीनां श्रुतत्वात्तेषामेव विभक्त्यर्थत्वेन भाव्यमिति मत्वा पृच्छति—**कः पुनरिति** । **एकत्वादय इति** । **कर्मणि द्वितीये**त्यादिसप्तमीनिर्देश एकत्वाद्यपेक्षः—कर्मणि यदेकत्वादि तत्र द्वितीयेति, न त्वभिधेयप्रतिपादनाय ॥ **निमित्तत्वायेति** । कर्माद्याश्रितानामेकत्वादीनामपि विभक्त्यर्थत्वे पारम्पर्येण कर्मादीनां निमित्तभावोस्त्येवेत्यभिप्रायेणैतदुक्तम् ॥ **अभिहित इति** । यदा वक्ष्यमाणानां कर्मादीनां विभक्त्यर्थत्वं तदा प्रातिपदिकार्थेनापि प्रथमार्थेन भाव्यं तस्य च प्रातिपदिकेनैवोक्तत्वाद् वृक्ष इत्यादौ प्रथमा न प्राप्नोति । एकत्वादीनां तु विभक्त्यर्थत्वे तदभिधानाय प्रथमा प्रवर्तत एवेति दोषाभावः ॥

(उद्द्योतः) **एकत्वादीनामिति** । संख्यावाक्यविभक्तिविधानयोरेकवाक्यत्वपक्षे एकत्वादीनां विशेष्यत्वमवलम्ब्येत्यर्थः ॥ आदिना द्वित्वादि । तदाह—**कर्मणीति** ॥ **एकस्य यदिति** । एकत्वस्याश्रयो यत्कर्मेत्यर्थः । द्व्येकयोरिति षष्ठीति भावः ॥ परे त्विदं चिन्त्यं बहुष्वित्यत्र सप्तमीदर्शनेन द्व्येकयोरित्यस्यापि सप्तमीत्वौचित्यात् । तस्मात्प्रातिपदिकार्थस्यैकत्वे सति तद्गतकर्मत्वशक्तौ द्वितीयैकवचनमित्यर्थ उचितः । अयं च चतुष्कं संख्यान्तं प्रातिपदिकार्थ इति पक्षे । त्रिकपक्षे तु कर्मणि द्वितीया भवतीत्येवार्थोस्य सूत्रस्य ततः कर्मण एकत्वे तदेकवचनमित्यर्थः संख्याबोधकस्य । इदमेवाभिप्रेत्याग्रे एतन्मते कर्मण एकत्वे इत्यादिक्रमेणार्थं दर्शयिष्यति भगवानित्याहुः ॥ **नार्थ इति** । प्रधानार्थस्योक्तत्वेन विशेषणीभूतार्थानुक्तावपि तेन न्यायेनातिप्रसङ्गविरहात् तन्मात्रबोधनस्य प्रथमया सिद्धत्वाच्चेति भावः ॥ **तदभिधानायेति** । उक्तार्थानामिति न्यायस्तु प्रधानार्थविषय इति भावः ॥ **तेषामेवेति** । तथा च संख्याया विभक्त्यर्थत्वमसम्भावितमिति भावः ॥ **सप्तमीनिर्देश इति** ॥ ननु द्वितीयायाः सूत्रे श्रुतत्वात्तदपेक्षयैव सप्तमी उचिता न त्वेकत्वापेक्षया, किं च संख्यायाः प्रायेण विशेषणत्वस्यैव दृष्टत्वाद् 'एकत्वविशिष्टे कर्मणि' इत्येवार्थ उचित इति चेत् ॥ न, कारकस्य प्रातिपदिकार्थत्वेन तत्र विधानानुपयोगाच्छुद्धनियमार्थत्वापेक्षया एकत्वविशेषणतया विधित्वद्वारा आर्थनियमस्यापि सिद्धिरिति विधित्वाय तथैवान्वय उचित इत्याशयात् । तत्र पक्षे यथा प्रातिपदिकेनोक्ते द्वितीयादयो भवन्ति तथा तिङाद्यभिहितेपि स्युरित्येतदर्थं स आवश्यकः ॥ **एकत्वादय** इत्यस्य त एवेत्यर्थः । एवं च संख्यारहितं चतुष्कं प्रातिपदिकार्थ इति पक्षे सूत्रमावश्यकमित्युक्तं भवति ॥ तदितरपक्षेषु च न कर्तव्यमिति ॥ पञ्चकपक्षेपि सूत्रमावश्यकमिति **बहुष्विति**सूत्रे भाष्यकैयटयोः स्पष्टम् ॥ पञ्चकपक्षे सुपां द्योतकत्वाद्वाचकयोर्द्योतकयोश्च समुच्चयस्य दृष्टत्वादन्याभिहितेपि स्यादतः स आवश्यकः ॥ वस्तुतस्तु **एकत्वादयो विभक्त्यर्था** इत्यस्य सूत्रे प्राधान्येन विभक्तिद्योत्यत्वेन बोधिता इत्यर्थः । एवं **कर्मादयो विभक्त्यर्था** इत्यस्यापि । यद्यपि द्योतकविषये क्वचिद् **द्विर्बद्धं सुबद्ध**मितिन्यायेन समावेशो दृष्टस्तथापि प्रकृते लक्ष्यानुसारा**दुक्तार्थाना**मित्येवाश्रीयते । परंतु अयं न्यायः सूत्रोक्तप्रधानविषय इति भावः । **उक्तार्थाना**मिति न्यायस्य द्योतकविषयेपि सञ्चारो दृश्यतेऽ**धिपरी**इति सूत्रे भाष्ये । अपुपौ द्वावित्यादौ व्यभिचारश्च तत्रैवोक्तः ॥ ननु प्राधान्यादेकत्वादीनामेव

निमित्तत्वं न कर्मादीनामत आह—कर्माद्याश्रितानामिति ॥
मा भूवन्निति । पाम्यसमासावितिशब्दः । भाष्ये—तेष्वभि-
हितेषु सामर्थ्यादिति । सामर्थ्यमत्रोक्तार्थानामप्रयोगरूपम् ।
स्वपक्षे नायं दोष इत्याह—एकत्वादीनां त्विति ॥

(प्रत्याख्यानवादिभाष्यम्)

न क्वचित्प्रातिपदिकेनानुक्तः प्रातिपदिकार्थः । उच्यते च प्रथमा । सा वचनाद्भविष्यति ॥ तवैव तु खल्वेष दोषः—यस्य ते एकत्वादयो विभक्त्यर्थाः । 'अभिहिते प्रथमाऽभाव' इति प्रथमा ते न प्राप्नोति । क? । पचत्योदनं देवदत्त इति ॥ किं कारणम्? । तिङोक्ता एकत्वादय इति । अनभिहिताधिकारं च त्वं करोषि, परिगणनं च ॥

(प्रदीपः) प्रत्याख्यानवाद्याह—न क्वचिदिति । वचनसामर्थ्यात् प्रातिपदिकेनोक्तेपि तदर्थे प्रथमा भविष्यति । द्वितीयादयस्त्वनभिहिते कर्मादौ सावकाशत्वादभिहिते न भविष्यन्ति ॥ तिङोक्ता इति । अनभिहितैकत्वाद्यभिधानाय तव विभक्तिविधानम् । पचतीति च कर्तुरेकत्वं तिङभिहितमिति प्रथमा न स्यादित्यर्थः ॥ परिगणनं चेति । तिङ्कृत्तद्धितसमासैरित्येतत् । अत्र च तिङस्त्येकत्वस्याभिधानमिति प्रथमाया अप्रसङ्गः ॥

(उद्द्योतः) द्वितीयादिषु वैषम्यं दर्शयति—द्वितीयादयस्त्विति ॥ अनभिहितैकत्वाद्यभिधानायेति । प्रातिपदिकार्थसूत्रे उपस्थितानभिहित इत्यस्य प्रातिपदिकार्थविशेषणत्वासम्भवेनैकत्वादिविशेषणत्वमिति भावः ॥ कर्तुरेकत्वमिति । येपि तिङ्वाच्यकारकगतसंख्यामारोप्य तत्रैव तिङर्थक्रियायामेव संख्यान्वय इति वदन्ति । तेषामपि आरोपमूलतया सोक्तप्रायैवेति बोध्यम् । अन्यथा तिङर्थाश्रयगताया उक्तत्वेपि चैत्रत्वविशिष्टरूपनामार्थगताया अनुक्तत्वेन तदसंगतिरेव स्यात् । न च क्रियायाः स्वत एकत्वेन तदारोपानपेक्षत्वेन कर्तृगतैकत्वस्य कथमुक्तत्वम् । तस्यापि साधने द्वित्वाद्यभावबुद्धिनिमित्तेक तदनारोपे सत्वात् । अन्यथा पचत इत्यादौ द्विवचनाद्यनापत्तिः । मम तु आरोपितयाप्युत्तरया संख्यया पूर्वसंख्याया बाधान्न दोषः आवृत्तिगतसंख्यारोपेण सहस्रदक्षिणत्वादिवत् । एवं च द्वित्वाद्यभावबुद्धौ द्रव्यस्य निःसंख्यत्वाभावेन साधने एकत्वमवगतमेवेति भाष्याशयात् ॥ ननु तिङ्सुपोर्युगपत्प्रवृत्तेर्वक्तुं शक्यत्वेन तिङोक्ता इत्यसंगतमत आह—भाष्ये—परिगणनंचेति । तथा च तिङ्कृदित्यादिपरिगणनबोधितापवादविषयपर्यालोचनया तिङुत्पत्तिपर्यन्तं सुप् प्रतीक्षत इत्यर्थः ॥

(आरम्भवादिभाष्यम्)

न क्वचित्तिङा एकत्वादीनामनभिधानम् । उच्यते च प्रथमा । सा वचनाद्भविष्यति ॥

(प्रदीपः) आरम्भवाद्याह—न क्वचिदिति । सर्वत्र पदमपेक्षितक्रियापदमेव प्रयुज्यते ॥ उच्यते चेति । प्रातिपदिकार्थसूत्रेणेत्यर्थः ॥

(उद्द्योतः) अस्तिर्भवन्तीपर इत्यस्य न्यायसिद्धत्वमाह—सर्वत्रचेति ॥ द्व्येकयोरिति सूत्रस्यान्यत्र सावकाशत्वात्सामर्थ्यासिद्धिमाशङ्क्याह—प्रातिपदिकार्थसूत्रेणेति ॥

(प्रत्याख्यानवाद्याक्षेपभाष्यम्)

ननु चेहानभिधानम्—वृक्षः प्लक्षः इति ॥

(आरम्भवादिसमाधानभाष्यम्)

अत्राप्यभिधानमस्ति ॥ कथम्? । वक्ष्यत्येतद्—"अस्तिर्भवन्तीपरः प्रथमपुरुषोऽप्रयुज्यमानोप्यस्ति" इति । वृक्षः प्लक्षः 'अस्ति' इति गम्यते ॥ तवैव तु खल्वेष दोषः—[यस्य ते कर्मादयो विभक्त्यर्थाः] अभिहिते प्रथमाभाव इति प्रथमा ते प्राप्नोति । क? । कटं करोति भीष्ममुदारं शोभनं दर्शनीयमिति । कटशब्दादुत्पद्यमानया द्वितीययाभिहितं कर्मेति कृत्वा भीष्मादिभ्यो द्वितीया न प्राप्नोति ॥ का तर्हि प्राप्नोति? । प्रथमा ॥ तद्यथा—'कृतः कटो भीष्म उदारः शोभनो दर्शनीयः' इति करोतेरुत्पद्यमानेन क्तेनाभिहितं कर्मेति कृत्वा भीष्मादिभ्यो द्वितीया न भवति । का तर्हि? । प्रथमा भवति ॥

(प्रदीपः) **भवन्तीपर इति** । लट्पर इत्यर्थः । ततश्च वृक्ष इत्यत्रापि तिङैकत्वस्याभिधानादनवकाशत्वात्तिङाऽभिहितेऽप्येकत्वादौ प्रथमा भवति ॥ एवमारम्भवादी स्वपक्षे दोषं परिहृत्य परपक्षे तमुद्भावयति—**तवैवेति । भीष्ममिति ।** भीष्मादिविशेषणविशिष्टस्य कटस्य करोतिक्रिययेप्सिततमत्वात्कर्मत्वम्, तच्च कटशब्दादुत्पन्नया द्वितीययाभिहितमिति भीष्मादिभ्यो द्वितीयाया अप्रसङ्गात् प्रथमा प्राप्नोति । आरम्भवादिनस्तु परिगणनात् कटशब्दादुत्पन्नया द्वितीययाभिहितेऽपि कर्मणि भीष्मादिभ्यो द्वितीया सिध्यतीति न दोषः ॥

(उद्द्योतः) अभिहिते प्रथमाभाव इति भाष्यस्याभिहिते प्रथमाया भावस्य प्रवृत्तेस्त्वयाङ्गीकारादित्यर्थः ॥ भीष्मादीनामपि कर्मत्वात्कथं प्रथमाप्राप्तिरत आह—विशेषणविशिष्टस्य कटस्येति । प्रधानगतकर्मत्वोक्तौ विशिष्टगतमपि तदुक्तमेव विशिष्टस्य तदपेक्षयातिरिक्तत्वाभावादिति शङ्कितुरभिमानः ॥ आरम्भे दोषाभावमाह—आरम्भवादिनस्त्विति ॥

(प्रत्याख्यानवादिभाष्यम्)

नैष दोषः । न हि ममानभिहिताधिकारोस्ति । नापि परिगणनम् । सामर्थ्यान्मे विभक्तीनामुत्पत्तिर्भविष्यति । अस्ति च सामर्थ्यम् । किम्? । कर्मविशेषो वक्तव्यः ॥

अथ वा कटोपि कर्म, भीष्मादयोपि । तत्र 'कर्मणि' इत्येव सिद्धम् ॥

अथवा कट एव कर्म, तत्सामानाधिकरण्याद्भीष्मादिभ्यो द्वितीया भविष्यति ॥

अस्ति खल्वपि विशेषः—कटं करोति भीष्ममुदारं दर्शनीयं शोभनमिति च 'कृतः कटः भीष्म उदारः शोभनो दर्शनीय' इति च करोतेरुत्पद्यमानः क्तः अनवयवेन सर्वं कर्माभिधत्ते, कटशब्दात्पुनरुत्पद्यमानया द्वितीयया यत् कटस्थं कर्म तत् शक्यमभिधातुं न कर्मविशेषः ॥

तत्रैव तु खल्वेष दोषः [यस्य ते एकत्वादयो विभक्त्यर्थाः] 'अभिहिते प्रथमाऽभावः' इति प्रथमा ते न प्राप्नोति । क? । एको द्वौ बहव इति । किं कारणम्?। प्रातिपदिकेनोक्ता एकत्वादय इति॥

(प्रदीपः) **कर्मविशेष इति** । भीष्मादियुक्तकटसंबन्धि कर्मत्वं प्रतिपाद्यम् । तत्र च यथा कटशब्देन भीष्मत्वादीनामनभिधानात्तदभिधानाय भीष्मादिशब्दप्रयोगः तथा द्वितीयापि तेभ्यो भविष्यति । नह्यन्यथा तद्विशिष्टत्वं कटस्य प्रत्याययितुं शक्यते ॥

अथ वेति । यद्यत्करोतिक्रिययाप्तुमिष्टतमं तत् सर्वं कर्म द्रव्यं गुणश्च । न ह्यसौ कटमात्रेण संतुष्यति । तत्र करोतिक्रियायां पृथक् सर्वेषां कर्मत्वे प्रत्येकं द्वितीयोत्पत्तिः पश्चात्त्वेकवाक्यतया विशेषणविशेष्यभावः ॥

यद्यपि गुणद्रव्ययोः करोतिना संबन्धस्तथापि तमप्श्रुत्या प्रकर्षस्याश्रितत्वाद् द्रव्यस्यैव क्रियान्तर उपयोक्ष्यमाणत्वादीप्सिततमत्वात्तस्यैव कर्मसंज्ञा, न गुणस्येति मत्वाह—**अथ वेति । तत्सामानाधिकरण्यादिति** । भीष्मादीनां स्वयमकर्मत्वेपि विशेष्यसंबन्धिन्यैव विभक्त्या भाव्यम् । तदेकयोगक्षेमत्वात् । केवलानां च प्रातिपदिकानां **परश्चेति** नियमादप्रयोगार्हत्वात् । ततो यथेश्वरसुहृदः स्वयं निर्द्धना अपि तदीयेन धनेन तत्फलभाजः एवं गुणा अपि ॥

क्तप्रत्ययेन द्वितीयाया वैधर्म्यं दर्शयति—**अस्ति खल्वपीति ॥ अनवयवेनेति** । साकल्येन ॥ **सर्वमिति** । भीष्मादिगुणगतमपीत्यर्थः ॥ **कटस्थमिति** । प्रातिपदिकार्थगताया एव कर्मशक्तेर्वाचिका द्वितीयेत्यर्थः ॥ **न कर्मविशेष इति** । भीष्मादिगुणगतं कर्मत्वमभिधातुं न शक्यमित्यर्थः ॥

एवं युक्त्या प्रत्याख्यानवादी स्वपक्षे दोषं परिहृत्य परपक्षे दूषणमाह—**तत्रैवेति ॥ एषदोष इति** । वक्ष्यमाणः ॥ **प्रातिपदिकेनोक्ता इति** । अनभिहितैकत्वाद्यभिधानाय तव विभक्तिविधानं तानि चैकादिभिरेवोक्तानीति प्रथमाया अप्राप्तिः ॥

(उद्द्योतः) भाष्ये—**सामर्थ्यादिति** । भीष्मादिपदानामपि द्वितीयोत्पादकसामर्थ्यसत्त्वादित्यर्थः । विशिष्टस्य कर्मत्वे विशेषणस्यापि द्वितीयोत्पादककर्मत्वशक्तिरूपसामर्थ्यवत्त्वम् । अन्यथा विशिष्टं कर्मेत्युक्तिव्याघातः । तच्च न कटपदोत्तरद्वितीययाभिहितमिति भावः ॥ तदाह—**तत्र च यथेत्यादिना** । विशिष्टगतैककर्मत्वप्रतिपादनेच्छायामयं प्रयोगः, तत्प्रतिपादनं च नोभयत्र द्वितीयां विनेति भावः ॥ अत्र पक्षे भीष्मपदात् कर्मत्वाद्यनालिङ्गितशुद्धगुणस्यैवोपस्थितिरितरस्य तद्वैशिष्ट्यप्रतीतौ पश्चाद्विशिष्टस्यैककर्मत्वशक्तिमत्तयोपस्थितिः। तथोपस्थितौ च भीष्माद्युत्तरद्वितीयापि सहकारिणीति तात्पर्यम् । तदाह—**नत्वन्यथेति । तद्विशिष्टत्वं कटस्ये**त्यनन्तरं विशिष्टस्य कर्मत्वं चेति शेषः। यथा कटं करोतीत्यत्र विशिष्टकर्मत्वं न प्रतीयते । एवं भीष्मः कटं करोतीत्यत्रापि विभिन्नविभक्तित्वाद्विशिष्टाप्रतीत्या तन्न प्रतीयत इति भावः ॥

पश्चादिति । तथा च न विशिष्टस्य कर्मत्वं किं तु क्रियायां कर्मत्वेनान्वितयोर्मनसा विशेषणविशेष्यभावबोध इति भाव इत्येके॥ परे तु साक्षात्फलाश्रयादेरपि द्रव्यद्वारा फलाश्रयादेरपि कर्मत्वादिकम्। एवं च भीष्मस्यापि पृथक्कर्मशक्तिविशिष्टस्यैव बोधनं भीष्मपदात्। द्रव्येणाभेदान्वयात्तु तस्याः शक्तेर्वाक्यार्थबोधे विशिष्याग्रहः भीष्मकटयोर्बोधश्च विशेषणविशेष्यभावेनैव । कारकाणां भावनान्वय इत्यस्य च साक्षात् स्वशक्तिनियामकाश्रयद्वारा वेत्यर्थात्तद्विरोधः॥ तदेव ध्वनयन् कैयट आह—**क्रियायां पृथक् सर्वेषां कर्मत्वे प्रत्येकं द्वितीयोत्पत्तिः पश्चात्त्वेकवाक्यतया विशेषणविशेष्यभाव इति। पश्चा**दित्यस्य द्वितीयोत्पत्त्यनन्तरमित्यर्थः । अक्षरस्वारस्यात्॥**पृथक् सर्वेषां कर्मत्वे** इत्यस्य च साक्षात्परम्परया वेति शेषः॥ **द्रव्यगुणयोः करोतिना संबन्ध** इत्यत्रापि स एव शेषः पूरणीयः। संबन्धश्च तदर्थफलाश्रयत्वरूपः ॥ एतेनात्र पक्षे प्रथमं सर्वेषां भावनान्वयः पश्चात्पार्ष्णिकः परस्परं मनसा विशेषणविशेष्यभावबोध इति परास्तम् ॥ ज्ञानद्वयकल्पनागौरवाच्चाननुभवाच्च । **एकवाक्यतये**ति कैयटेन शाब्दस्यैव विशेष्यविशेषणभावस्य स्वीकाराच्चेत्याहुः ॥

क्रियान्तरे। तद्विशेषे आसनशयनादिरूपे॥ **ईप्सिततमत्वादि**ति। साक्षात् क्रियान्वय्येव हीप्सिततमम्। एवं करणसंज्ञापि साधनतमत्वाद् द्रव्यस्यैवेति बोध्यम् ॥ परंत्विदं चिन्त्यम्, अश्वेन पथा दीपिकया व्रजतीत्यादौ सर्वेषां करणत्वानापत्त्या कारकान्तरापेक्षयैव प्रकर्षो, न तु स्वकक्षायामपीति स्वयमेवोक्तत्वात् । गां पयो दोग्धीत्याकडारसूत्रभाष्यासंगतेश्चेति दिक् ॥ **अथवेति । सामानाधिकरण्यं** नाम अनेकस्य पदस्य विशेष्यतयैकार्थबोधकत्वं यदि भिन्नशक्तित्वे स्यात्तदा शक्तिभेदेनार्थस्यापि भेदादेकार्थत्वं भज्येत तस्माद् 'विशेष्यसमानशक्तिकत्वं तदभिन्नविशेषणानाम्' इति नियमात्तत्स-

मानविभक्तिकत्वमेव ॥ फलाश्रयत्वादिवत्तत्समानाधिकरणत्वमपि विभक्त्युत्पत्तौ नियामकमिति तदुपपादयति—ततोयथेति । यथा मैत्रीभङ्गभिया सधनो निर्धनस्य स्वधनेन स्वसमानवासोऽलङ्कारादीन् करोति एवं सामानाधिकरण्यभङ्गभिया स्वशक्तिं तत्रारोप्य स्वसमानविभक्तिकत्वं संपादयतीति भावः ॥

नन्वेवमेव कुतः कट इत्यादावपि भीष्मादिभ्यो द्वितीया स्यादत आह—भाष्ये—अस्तिखल्वपीति ॥ भीष्मादिगुणगतम् इत्यस्य तद्गुणविशिष्टगतमित्यर्थः ॥ गुणगतं कर्मत्वमिति ॥ भाष्ये कर्मशब्दः शक्तिपर इति भावः । अयं भावः—क्तस्य धातोरुत्पत्त्यार्थप्रकृतिगतधर्माभावादन्यगते तत्राभिधातव्ये यत्प्रकृतिवाच्यक्रियानिरूपितकर्मत्वशक्तिमत् तत्सर्वगता साभिधीयत इति युक्तम्। द्वितीयायाः प्रातिपदिकादुत्पत्त्या स्वप्रकृतिभूतप्रातिपदिकार्थकर्मत्वलाभात्तदेव बोध्यम्, नान्यदिति ॥

भीष्मं कटमित्यादौ आरम्भवादे पूर्वोक्तप्रथमाप्राप्तिरूपदोषाभावादेष इत्यनुपपन्नमत आह—वक्ष्यमाणइति । तिङभिहिते वचनसामर्थ्याद्दोषपरिहारेपि प्रकृत्यभिहिते दोषः । तयाऽनभिहितैकत्वादिके वृक्ष इत्यादौ तस्याश्चारितार्थ्यादित्याह—अनभिहितैकत्वादीति । एकं पश्येत्यादौ द्वितीया तु कर्मणोऽनभिहितत्वादेकत्वे उक्तेपि भविष्यतीति मत्वा प्रथमाभावापत्तिरेव कृता ॥

(आरम्भवादिभाष्यम्)

कर्मादिष्वपि वै विभक्त्यर्थेषु अवश्यमेकत्वादयो निमित्तत्वेनोपादेयाः—कर्मण एकत्वे, कर्मणो द्वित्वे, कर्मणो बहुत्वे, इति । न चैकत्वादीनामेकत्वादयः सन्ति । अथ सन्ति, ममापि सन्ति । तेष्वनभिहितेषु प्रथमा भविष्यति ॥

अथ वा उभयवचना ह्येते द्रव्यं चाहुर्गुणं च । यत्स्थोसौ गुणः तस्यानुक्ता एकत्वादय इति कृत्वा प्रथमा भविष्यति ॥

अथ वा संख्या नामेयं परप्रधाना संख्येयमनया विशेष्यम् । यदि चात्र प्रथमा न स्यात् । संख्येयमविशेषितं स्यात् ॥

अथ वा वक्ष्यति तत्र वचनग्रहणस्य प्रयोजनम्-उक्तेष्वप्येकत्वादिषु प्रथमा यथा स्यादिति ॥

अथ वा समयाद्भविष्यति ॥

(प्रदीपः) आरम्भवादी परस्य तुल्यदोषतामाह—**कर्मादिष्वपीति** । यस्यापि कर्मादयो विभक्त्यर्थास्तेनाप्येकवाक्यता बहुषु बहुवचनमित्यादेः **कर्मणि द्वितीयेत्यादी**नामभ्युपगन्तव्या । गुणप्रधानभाव एव तु तस्य विपरीतः । तत्र प्रातिपदिकार्थगतैकत्वादिविशिष्टे कर्मणि द्वितीयेत्येवमादिर्वाक्यार्थस्तस्य संपद्यते ॥ **कर्मण एकत्वे इति** । नन्वेकत्वादीनां विशेषणत्वमभिधानीयं कर्मादीनाञ्च विशेष्यत्वं तत्र कस्मात् कर्मणो विशेषणत्वं प्रतिपाद्यते । नैष दोषः—प्रातिपदिकार्थस्यैकत्वे सति तद्विशिष्टस्य कर्मणो वाचिका द्वितीयेत्ययमत्रार्थो विवक्षितः । ततश्च प्रातिपदिकार्थव्यतिरेकेणान्येषामेकत्वादीनां विशेषणीभूतानामभावादेक इत्यादौ अपतोपि प्रथमा न स्यादित्यर्थः ॥ **अथ सन्तीति** । व्यतिरिक्तानीत्यर्थः । तदुक्तं हरिणा—

> **निमित्तमेक इत्यत्र विभक्त्या नाभिधीयते ।**
> **तद्गतस्तु यदेकत्वं विभक्तिस्तत्र वर्तते ॥**

इति । यथा शतमित्यत्र प्रवृत्तिनिमित्तं शतसंख्याऽन्या अन्या च विभक्तिवाच्या प्रातिपदिकार्थगतैकत्वसंख्या । तथैक इत्यत्रापि प्रवृत्तिनिमित्तविभक्तिवाच्ये द्वे एकत्वे ॥

एवं शब्दशक्त्याश्रयेणैकत्वादिभेदेनैव समाधायाभेदपक्षेपि समाधातुमाह—**अथ वेति** । गुणोपसर्जनं द्रव्यं प्रातिपदिकेनाभिधीयते । द्रव्योपसर्जनस्तु गुणो विभक्त्यर्थः । यथा शौक्ल्यमिति गुणोपसर्जनद्रव्याभिधायिनः शुक्लशब्दाद् द्रव्योपसर्जने तस्मिन्नेव गुणे भावप्रत्ययः ॥ **यत्स्थोसाविति** । यस्मिन्नेव द्रव्ये स्थित एकत्वादिगुणस्तस्य द्रव्यस्यानुक्ता एकत्वादयः प्राधान्येनेति भावः ॥

संख्येयमविशेषितमिति । केवलस्य प्रातिपदिकस्य प्रयोगाभावात् प्रथमाया अभावे एकादिशब्दानुच्चारणात् ॥

एवं युक्त्या प्रथमोत्पत्तिं प्रतिपाद्य वचनेन प्रतिपादयितुमाह—**अथ वेति ॥ समयादिति** । परश्चेत्यस्मात् **प्रत्ययपरैव** प्रकृतिः प्रयोक्तव्या न केवलेत्येवंरूपादित्यर्थः ॥

(उद्द्योतः) ननु कर्मादीनां विभक्त्यर्थत्वे एकत्वादीनां निमित्तत्वं कथमतस्तदुपपादयति—**यस्यापीति ॥ प्रातिपदिकार्थगतैकत्वादिविशिष्टे कर्मणीति** । सामानाधिकरण्यसम्बन्धेनैकत्वविशिष्टकर्मशक्तावित्यर्थः ॥ **वाचिकेति** । बोधिकेत्यर्थः । द्योतकत्वपक्षस्यैवोचितत्वादेकत्वादीनां विशेषणतयैव भानात् । एवं चैकत्वविशिष्टे प्रातिपदिकार्थे प्रथमेत्यर्थे तदपेक्षयातिरिक्तं यत्रैकत्वं **वृक्ष** इत्यादौ तत्रैव स्यात् न त्वेक इत्यादौ, इत्याह—**सत्यञ्चेति** । **उक्तार्थाना**मित्यस्य प्रधानार्थविषयत्वादेकत्वे उक्तेपि प्रधानकर्माभिधानाय द्वितीयादीनामेतन्मतेपि सिद्धिरिति तदनापत्तिर्नाकारि ॥ एतद् भाष्यं हरिणाप्येवमेव व्याख्यातमित्याह—**तदुक्तमिति** । **निमित्तम्** । प्रवृत्तिनिमित्तम् ॥ **द्वे एकत्वे इति** । द्वयोरपि तयोर्भासमानो द्वावित्यादाविवैकरूपेणैव भानाच्च बोधानुभवविरोधौ ॥

इयं च कल्पना शब्दशक्त्याश्रयेत्याह—**एवं शब्देति** । अत्रापि पक्षे प्रातिपदिकेनैकत्वविशिष्टद्रव्याभिधानाद्दोषस्तदवस्थोत आह—**गुणोपसर्जनमिति** ॥ **द्रव्योपसर्जन इति** । गुणगुणिनोरभेदाच्चैकः पट इति सामानाधिकरण्यम् ॥

ननु प्रातिपदिकस्यैकत्वादिविशिष्टे शक्त्या तेनैव द्रव्यं विशेषयितुं शक्यं किं तत्र विभक्त्येत्यत आह—**केवलस्येति** । अयं भावः—वृद्धव्यवहाराच्छक्तिग्रहः । वृद्धव्यवहारश्च विभक्त्यन्तेनैवेति विभक्तिसमभिव्याहृते गृहीतायाः शक्तेस्तदभावेऽनुद्बोधात् पदार्थानुपस्थित्या संख्येयमविशेषितम् । एवं च पदार्थोपस्थित्यन्यथानुपपत्त्याऽभिहितेपि विभक्त्युत्पत्तिरिति॥ लोकव्यवहारे प्रयुज्यमानानामेव साधूनां साधुत्वान्वाख्यायकमिदं शास्त्रमिति वृद्धव्यवहारे एव किं मूलमिति न शङ्क्यम् ॥

(आक्षेपभाष्यम्)

यदि सामयिकी, न नियोगतः। अन्याः कस्मान्न भवन्ति? ॥

(उद्द्योतः) भाष्ये—**न नियोगत इति** । न नियमत इत्यर्थः ॥

(समाधानभाष्यम्)

कर्मादीनामभावात् ॥

(प्रदीपः) **कर्मादीनामिति** । कर्मण्येव द्वितीयेत्येवं द्वितीयादीनां नियतत्वात् ॥

(आक्षेपभाष्यम्)

षष्ठी तर्हि प्राप्नोति? ॥

(प्रदीपः) **षष्ठी तर्हीति** । कर्माद्यभावः शेष इति भावः ॥

(उद्द्योतः) प्रातिपदिकार्थस्याशेषत्वात्कथं तत्र षष्ठीत्यत आह—**कर्मादीति** । तावन्मात्रमेव शेष इत्यभिमानः ॥

(समाधानभाष्यम्)

शेषलक्षणा षष्ठी । अशेषत्वान्न भविष्यति ॥

(प्रदीपः) **अशेषत्वादिति** । प्रातिपदिकार्थस्य प्रथमाविधावुपयोगात्तस्य चाव्यतिरिक्तस्येह सद्भावात् ॥

(उद्द्योतः) **अव्यतिरिक्तस्येति** । अतिरिक्तेन विशिष्टो व्यतिरिक्तस्तदभिन्नस्येत्यक्षरार्थः । एवं च कारकप्रातिपदिकार्थव्यतिरिक्तः शेष इति नात्र षष्ठी तदतिरिक्तस्य कस्याप्यप्रतीतेरिति भावः॥

(आक्षेपभाष्यम्)

एवमपि व्यतिकरः प्राप्नोति—एकस्मिन्नपि द्विवचनबहुवचने प्राप्नुतः द्वयोरप्येकवचनबहुवचने प्राप्नुतः बहुष्वप्येकवचनद्विवचने प्राप्नुतः ॥

(समाधानभाष्यम्)

अर्थतो व्यवस्था भविष्यति ॥

(प्रदीपः) **अर्थतो व्यवस्थेति** । सामर्थ्यादित्यर्थः । एक इत्यत्रैकमेवैकत्वं तच्च प्रातिपदिकेनाभिहितमित्यप्राप्ता प्रथमा समयवशेन प्राप्यते । तत्र यथा समयश्च पालितो भवत्येकत्वानुगुणं चान्यत्र तदभिधाने दृष्टसामर्थ्यं वचनं भवति तथा कर्तव्यमित्यर्थः । तदेवं संख्या विभक्त्यर्थ इति दर्शनाश्रयेण सूत्रं स्थापितम् ॥

(उद्द्योतः) अर्थाभावेपि समयपरिपालनाय विभक्तौ कथमर्थतो व्यवस्थेत्यत आह—**सामर्थ्यादिति** ॥ तदेवोपपादयति—**एकइत्यत्रेति** । विरुद्धविभक्त्यपेक्षयानुवादकविभक्तिर्न्याय्येति भावः॥ पक्षद्वयेपि दोषाभावप्रतिपादनात्**संख्या सुबर्थ** इति दर्शने सूत्रं कार्यम्, दर्शनान्तरे नेति स्थितम्॥ तत्रारम्भपक्षे परिगणनादिप्रवृत्तिं बोधयितुमाह—**तदेवमिति** ॥ **सङ्ख्या विभक्त्यर्थ इति** । सूत्रे प्राधान्यात्तस्या विभक्तिद्योत्यता कारकं तु तद्विशेषणत्वेन तथेति दर्शनमित्यर्थः ॥

(परिगणनाधिकरणम्)

(भाष्यम्) **परिगणनं कर्तव्यम् ॥**

(१४६२ परिगणनवार्तिकम् ॥ ४ ॥)

॥ * ॥ तिङ्कृत्तद्धितसमासैः परिसंख्यानम् [उत्सर्गे हि प्रातिपदिकसामानाधिकरण्ये विभक्तिवचनम्] ॥ * ॥

(भाष्यम्) **तिङ्कृत्तद्धितसमासैः परिसंख्यानं कर्तव्यम् । तिङ—क्रियते कटः । तिङ ॥ कृत्—कृतः कटः । कृत् ॥ तद्धितः—औपगवः कापटवः । तद्धितः ॥ समास—चित्रगुः शबलगुः । समास ॥ उत्सर्गे हि प्रातिपदिकसामानाधिकरण्ये विभक्तिवचनम् । उत्सर्गे हि प्रातिपदिकसामानाधिकरण्ये विभक्तिर्वक्तव्या । क? । कटं करोति भीष्ममुदारं शोभनं दर्शनीयमिति । कटशब्दादुत्पद्यमानया द्वितीययाभिहितं कर्मेति कृत्वा भीष्मादिभ्यो द्वितीया न प्राप्नोति ॥**

(प्रदीपः) **औपगव इति** । अपत्यापत्यवत्संबन्धस्य तद्धितेनोक्तत्वात् षष्ठी न भवति ॥ **चित्रगुरिति** ॥ समासेन स्वस्वामिसंबन्धस्याभिधानात् षष्ठ्यभावः ॥ **उत्सर्गे इति** । **अनभिहित** इति सामान्येनोच्यमान इत्यर्थः । यत्र बहूनि प्रातिपदिकानि समानाधिकरणानि विवक्षितानि तत्रैयोगक्षेम-

त्वादेकत उत्पन्नया द्वितीयया सर्वप्रातिपदिकार्थगतं कर्मत्वमभिहितमित्यन्येभ्यो द्वितीया न स्यात्॥

(उद्योतः) भाष्ये—**तिङ्क्रियते कट** इति। न चात्र सङ्ख्याकारकयोरुभयोरप्युक्तेः **सङ्ख्या विभक्त्यर्थ** इति पक्षेपि नेदमनभिहिताधिकारप्रयोजनमिति तिङ्ग्रहणं व्यर्थमिति वाच्यम्। संख्यायाः क्रियायामेवान्वयेन कारकगतसङ्ख्यायाः शब्देनानभिधानादित्याशयः॥ एवं च पचत्योदनं देवदत्त इत्यादौ तिङोक्ता एकत्वादय इति प्रथमा न प्राप्नोतीति पूर्वोक्तभाष्यमेकदेश्युक्तिरिति यथा कथंचिद्व्याख्येयमिति सूचितम्॥ तिङ्कृतोरिव तद्धितसमासयोः कस्मिंश्चिद्विभक्त्यर्थेऽविधानादाह—**अपत्यापत्यवदिति**॥ **तद्धितोक्तत्वादिति**। तद्धितान्तोक्तत्वादित्यर्थः॥ नन्वेतयोः संबन्धस्य प्रातिपदिकार्थत्वेनाशेषत्वान्न षष्ठीप्राप्तिः। कारकप्रातिपदिकार्थ व्यतिरिक्तो हि तत्र शेषः॥ न च कर्मादिव्यतिरिक्त एव शेष इत्याशयेनैते उदाहरणे। यद्वा–संबन्धो न प्रातिपदिकार्थः, प्रवृत्तिनिमित्ततदाश्रयभिन्नत्वादिति वाच्यम्। घटपदाद् घटघटत्वयोः संबन्धस्य भानेन तत्र षष्ठ्या दुर्वारतापत्तेः। तत्र हि नैतदन्यतमेनाभिधानमिति चेत्॥ सत्यम्, वाक्येऽस्य संबन्धस्य षष्ठ्यर्थत्वं दृष्ट्वाऽत्राप्यप्रातिपदिकार्थत्वमित्यभिमानात्। किं च **का तर्हि स्यात्? शेषलक्षणा षष्ठी अशेषत्वान्न, समयाच्च द्वितीयैवे**त्यग्रिमग्रन्थेन कटं भीष्ममित्यादौ अभिहितत्वादप्राप्तद्वितीयासाधनार्थं परिगणनमित्येतत्खण्डनपरेण परिगणनप्रत्याख्यानवदेतयोरुदाहरणत्वाभावस्यापि कथनेन तद्धितसमासोदाहरणमधिकमित्यर्थस्यापि कथनात्। **अनेकमन्यपदार्थे** इति सूत्रे भाष्येप्यनयोरनुदाहरणत्वं सूचितम्। न च शतेन क्रीतः शत्यः प्राप्तमुदकं यं प्राप्तोदक इत्यादि तद्धितसमासोदाहरणमिति वाच्यम्। प्राप्तोदक इत्यादौ प्राप्तोदककर्मेत्यादिप्रकारेणैव बोधः। तत्र विशेष्ये तन्निरूपकत्वभानेन विशेषणमादाय तात्पर्यावसानमिति द्वितीयादिप्रयोजककर्मत्वादेः शब्दादबोधेन द्वितीयाद्यप्राप्तेः। एवं च विशेषणत्वव्यत्यासोपि न। उपजीव्यस्यैकधर्मिबोधकत्वरूपसामानाधिकरण्यस्य च न बाधः। चित्रगुरित्यादौ चित्राणां गवामयमित्यादौ यथा तस्य षष्ठीप्रयोजकता तथात्रापि स्वात्तेनैव रूपेण भानादिति बोध्यम्। एवं यथा क्रीतशब्दे धातुना क्रियोपस्थाप्यते, न तेन रूपेण शत्यशब्देनेति न तदर्थे इतरकारकान्वयः। इदं च **कर्तृकर्मणो**रित्यत्र भाष्ये ध्वनितम्। अतो न तदर्थकर्मणो विभक्तिप्राप्तियोग्यता। एवं च **सांप्रत**मित्यादिनिपातैरपि न तेन रूपेण क्रियायाः कारकस्य चोक्तिरिति न तदन्वयिनि विभक्तिप्रसक्तिः। अतो निपातेनाभिहितत्वाद्विभक्त्यनुत्पत्तिरित्यपि चिन्त्यमेव। **नारद इत्यबोधि स** इत्यत्रापि नारद इतीत्यनेन श्रीकृष्णीयज्ञानाकारानुवादात्तत्र न द्वितीयादिप्रसक्तिरित्यलम्॥ परिगणनफलमाह—भाष्ये—उत्सर्गे हीति। तद्व्याचष्टे—**सामान्येनेति**॥ **एकयोगक्षेमत्वादिति**। एकार्थबोधकत्वस्यैव सामानाधिकरण्यपदार्थत्वादिति भावः॥

(आक्षेपभाष्यम्)

का तर्हि स्यात्?॥

(प्रदीपः) परिगणनमन्तरेणाप्येतं दोषं परिहर्तुं पृच्छति—**का तर्हीति**॥

(समाधानभाष्यम्)

षष्ठी॥

(प्रत्याख्यानवादिभाष्यम्)

शेषलक्षणा षष्ठी अशेषत्वान्न भविष्यति। अन्याः अपि न प्राप्नुवन्ति॥ किं कारणम्?। कर्मादीनामभावात्॥ समयश्च कृतः—'न केवला प्रकृतिः प्रयोक्तव्या न च केवलः प्रत्ययः' इति। न चान्या उत्पद्यमाना एतमभिसंबन्धमुत्सहते वक्तुमिति कृत्वा द्वितीया भविष्यति॥

अथवा कटोपि कर्म भीष्मादयोपि, तत्र 'कर्मणि' इत्येव सिद्धम्॥

अथ वा कट एव कर्म तत्सामानाधिकरण्याद्भीष्मादिभ्यो द्वितीया भविष्यति। तस्मान्नार्थः परिगणनेन॥

(उद्योतः) भाष्ये—**कर्मादीनामभावादिति**। अनभिहितकर्मादीनामभावादित्यर्थः॥ **अन्येति**। प्रथमेत्यर्थः॥ **एतमभिसंबन्धं** सामानाधिकरण्यरूपम्। इतरसंबन्धानवच्छिन्नविशेष्यविशेषणभावः सामानाधिकरण्यम्॥ **द्वितीया भविष्यतीति**। अस्याशय उक्तः॥ **तस्मान्नार्थ** इति। भीष्मादिभ्यो द्वितीयादेः प्रकारान्तरेण वारणाद्यावत्यान्तरस्याभावाच्चेति भावः॥ **यत्तु** एतद्बलेन निपातेनाप्यभिधानमिति वदन्ति। तदयुक्तम्। **उक्तरीत्या** निष्फलं च विभक्त्यर्थे यदव्ययं तेन समासविधायकास्य[?] सिद्धेतिदिक्॥

(गुणप्रधानक्रिययोः प्रधानानभिहितग्रहणाधिकरणम्)

(१४६३ आक्षेपवार्तिकम्॥ ५॥)

॥ * ॥ द्वयोः क्रिययोः कारकेऽन्यतरेणाभिहिते विभक्त्यभावप्रसङ्गः॥ * ॥

(भाष्यम्) **द्वयोः क्रिययोः कारकेऽन्यतरेणाभिहिते विभक्तिर्न प्राप्नोति। क?। प्रासादे आस्ते शयने आस्त इति॥ किं कारणम्?। सविप्रत्ययेनाभिहितमधिकरणमिति कृत्वा सप्तमी न प्राप्नोति॥**

(प्रदीपः) **अनभिहित** इति पर्युदासे प्रसज्यप्रतिषेधे च दोषदर्शनात्तन्निराकरणाय दोषोद्भावनं कर्तुमाह—**द्वयोरिति**। प्रासाद आस्त इत्यत्र सदिक्रियाया आसिक्रियायाश्चैकमधिकरणं प्रासादाख्यम्। तत्रान्यतरेण सदिप्रत्ययेन घञाऽभिहितमित्यभिहिते नेति सप्तमी न प्राप्नोति। अभिहितादन्यत्रेत्यत्रापि पक्षेऽभिहितत्वादधिकरणस्याभिहितादन्यत्वं नास्तीति न प्राप्नोति। द्रव्यं च कारकं मन्यते तद्व्यतिरेकेण शक्तिसद्भावे प्रमाणाभावात्। न तावत् प्रत्यक्षं द्रव्यव्यतिरिक्तस्वरूपपरिच्छेदि समुपजायते। द्रव्यस्वरूपातिरेकेण शक्तिरूपानुपलम्भात्। प्रत्यक्षाप्रवृत्तौ च तत्पूर्वकस्यानुमानस्यापि शक्तिसद्भावावेदने नास्ति प्रवृत्तिः। कार्यं च द्रव्यस्वरूपायत्तमेवेति कार्यव्यतिरेकादपि नास्ति शक्तिसद्भावावगमः॥

(उद्योतः) **तन्निराकरणायेति**। ननु परिगणनप्रत्याख्यानमूलकोयं दोषः। घञः कृत्त्वेन परिगणनेपि दीपत्वादवध्यादिति भावः॥ **नास्तीति**। अभिहितत्वावच्छिन्नप्रतियोगिताको भेदो नास्तीत्यर्थः॥ ननु क्रियाभेदे शक्तेर्भिन्नत्वात्सदिनिरूपितस्याभिहितत्वेपि आसिनिरूपितस्याभिहितत्वासिद्धिरित्यत आह—**द्रव्यं चेति**॥ **तद्व्यतिरेकेणेति**। गुणसमूहो द्रव्यमिति भावः॥ **न तावत्प्रत्यक्षमिति**। शक्तेरतीन्द्रियत्वादित्यर्थः॥ **स्वरूपेति**। शक्तिस्वरूपेत्यर्थः॥ अत एव संबन्धस्य दुर्ग्रहत्वात् तत्पूर्वकमनुमानमपि नेत्याह—**तत्पूर्वकस्येति**॥ ननु यथा दाहके सत्यपि दाहादिकार्यस्य कादाचित्कत्वानुपपत्त्या शक्तिरवगम्यते तद्वदिहाप्यस्तु अत आह—**कार्यं चेति**॥ **द्रव्यस्वरूपेति**। नतु तद्व्यतिरिक्तशक्त्यायत्तमित्यर्थः॥

(१४६४ बाधकवार्तिकम् ॥ ६ ॥)

॥ * ॥ न वान्यतरेणानभिधानात् [अनभिहिते हि विधानम् ॥ * ॥]

(भाष्यम्) **न वा एष दोषः। किं कारणम्?। अन्यतरेणानभिधानात्। अन्यतरेणात्रानभिधानम्। सदिप्रत्ययेनाभिधानम्। आसिप्रत्ययेनानभिधानम्। यतोऽनभिधानं तदाश्रया सप्तमी भविष्यति॥**

कुतो नु खल्वेतत्सत्यभिधाने चानभिधाने चानभिहिताश्रया सप्तमी भविष्यति, न पुनरभिहिताश्रयः प्रतिषेध इति?।

अनभिहिते हि विधानम्*। अनभिहिते हि सप्तमी विधीयते। नाभिहिते प्रतिषेधः॥

(प्रदीपः) पर्युदासं शक्तिसाधनपक्षञ्चाश्रित्याह—**न वेति**॥ प्रसज्यप्रतिषेधवाद्याह—**कुतो नु खल्विति**॥ पर्युदासमाश्रित्याह—**अनभिहिते हीति**॥

(उद्योतः) **शक्तिसाधनपक्षं चेति**। एकस्यैव परस्परविरुद्धकर्तृकर्मादिव्यपदेशः शक्तिं गमयति। एवं चैकनिरूपितशक्तेरभिधाने तच्छक्त्यन्तरस्यानुक्तत्वमेवेत्येतदाशयः॥ पर्युदासपक्षे कुत इति प्रश्नानुपपत्तिरत आह—**प्रसज्येति**। द्रव्यं कारकमित्यपि बोध्यम्॥

(आक्षेपसाधकभाष्यम्)

यद्यपि तावदत्रैतच्छक्यते वक्तुं यत्रान्या चान्या च क्रिया। यत्र तु खलु सैव क्रिया तत्र कथम्—आसने आस्ते शयने शेत इति!॥

(प्रदीपः) पर्युदासेपि दूषणमाह—**यद्यपि तावदिति**। आसन आस्त इत्यत्रैकैवासनक्रिया तस्याश्चाधिकरणं ल्युटाभिहितमिति सप्तम्या अप्राप्तिरित्यर्थः॥

(उद्योतः) **एकैवासनक्रियेति**। तथा च तन्निरूपिता शक्तिरप्येकैवेति भावः॥

(आक्षेपबाधकभाष्यम्)

अत्राप्यन्यत्वमस्ति। कुतः?। साधनभेदात्कालभेदाच्च। एकस्यात्रासेरासिः साधनम्, सर्वकालश्च प्रत्ययः। अपरस्य बाह्यं साधनम्, वर्तमानकालश्च प्रत्ययः॥

(प्रदीपः) **अत्राप्यन्यत्वमिति**। भिन्नपदप्रत्याय्ये भिन्ने आसनक्रिये इत्यर्थः। एकपदोपात्ते क्रियासाधनसंबन्धे अनेन विभक्तयो निवार्यन्ते न तु वाक्योपात्ते॥ **आसिः साधनमिति**। आसनमित्यत्र यासिक्रिया तस्या आसिक्रिया साधनम्॥ कथमेतदिति चेत्। उच्यते—आस्यतेस्मिन्नित्यासनमुच्यते। यदि चासनक्रियास्ते संनिधीयते ततस्तदपेक्षं तदासनमुच्यते। एवं सामर्थ्यादासेरासिः कर्ता भवति॥ नन्वेवं सत्यासनमित्यत्र या आसिक्रिया सा अन्यस्या आसिक्रियायाः साधनं भवति। न त्वस्या अन्या। एवं तर्ह्यर्थान्तरेस्य ग्रन्थस्य तात्पर्यम्। तदयमत्र परमार्थः—आसनशयनकरणापादानसंप्रदानादिशब्दैरासनादिक्रियायोग्यं वस्तुमात्रमनुद्भूतशक्तिकमभिधीयते। तत्र शक्त्युद्भवप्रतिपादनाय विभक्तिरवश्योत्पाद्या। ततश्चासिः **साधनमिति** साधनान्तरनिरासः क्रियते। शब्दव्युत्पत्तये केवलमत्रासिक्रियोपादीयत इत्यर्थः॥ **सर्वकालश्च प्रत्यय इति**। कालविशेषानुपादानेन ल्युटो विधानात्॥ **बाह्यमिति**। देवदत्तादिकमित्यर्थः॥

(उद्योतः) प्रत्यभिज्ञयैकत्वावगतेः कथमन्यत्वमत आह—**भि-**

न्नपदेति । प्रत्यभिज्ञा तु साजात्यनिबन्धनेति भावः ॥ नन्वेवमनभिहित इति सूत्रं व्यर्थमत आह—**एकपदेति** । अत एव गोघ्नाय हन्ति कृतं कटमानय भीमाद्बिभेतीत्यादौ चतुर्थ्यादय इति भावः । तथा च पदभेदकृतभेदमर्थ आरोप्य तन्निरूपितशक्तिभेदोपीत्यभिप्रायः॥ एकस्येत्यस्यार्थमाह—**आसनमित्यत्रेति** ॥ आसनत्वसिद्ध्यनुपपत्तिलक्षणसामर्थ्येनासिसाधनत्वमाह—**आस्यत इति** । आस्ते इति स्वोक्तस्य व्याख्यानम्—**संनिधीयतइति** । असिन्निति प्रत्ययार्थत्वेन निर्दिष्टवस्तुन आसिक्रियासन्निधानमन्तरेणासनत्वायोगादासिक्रियासाधनत्वं कृत्प्रकृत्यर्थस्यासेः स्वाधिकरणद्रव्यद्वारेष्टव्यम् । तदाह—**एवंसामर्थ्यादिति** ॥ **कर्त्ता भवतीत्यस्य** कारकं साधनं भवति स्वप्रकृतिकल्युडन्तार्थद्वारेत्यर्थः ॥ **एकस्यात्रासेरिति**—भाष्ये आसिः शेतेरप्युपलक्षणम् ॥ नन्वेवं ल्युट्प्रकृतिभूतासिक्रियायास्तिङन्तोपात्ता आसिक्रिया साधनमिति भाष्योक्तं न सिद्धमित्याशङ्कते—**नन्विति** ॥ केचित्तु आसनक्रिया आस्तेऽसिन्नित्यासनमिति व्युत्पत्तिः । प्रकृतिभूत आस्तिरस्त्यर्थः । तदर्थस्यापि लोके प्रयोगदर्शनात् । एवं शेतिरपि तिष्ठत्यर्थो जलाशय इत्यादौ । उभयत्राप्यासिग्रहणमुपलक्षणम् । एवं च भाष्यं समञ्जसमेवेत्याहुः ॥ **वस्तुमात्रमिति** । नासादिक्रियाधिकरणत्वेन तद्बोधः । किं त्वासनत्वेनेत्यर्थः ॥ तदेवाह—**अनुद्भूतशक्तिकमिति** ॥ **शब्दव्युत्पत्तये इति** । अनुलोमादिवद्रूढा एवेत्यर्थः । अत एव पक इत्यादौ केनेति कर्त्राकाङ्क्षावदासनमित्युक्ते न तदाकाङ्क्षा । अत एवआसिः साधनम् इत्यस्य साधनान्तरनिरासे तात्पर्यमुक्तम् ॥

(साधननिर्णयाधिकरणम्)

(आक्षेपभाष्यम्)

किं पुनर्द्रव्यं साधनम् । आहो स्विद् गुणः ? । किं चातः ? ।

यदि द्रव्यं साधनम्, नैतदन्यद्भवत्यभिहितात् ।

अथ हि गुणः साधनम्, भवत्येतदन्यदभिहितात् ।

अन्यो हि सदिगुणः । अन्यश्चासिगुणः ॥

किं पुनः साधनं न्याय्यम् ? ॥

(प्रदीपः) **किं पुनरिति** । यदि द्रव्यं साधनं तदा तदेकमेव तच्चाभिहितमिति पूर्वोक्तपरिहारो न संगच्छते । अथ शक्तिः साधनं तदा तस्या भेदादभिहितत्वानभिहितत्वसंभवाद्भवति समाधानमिति मन्वानस्य प्रश्नः । आश्रितत्वाच्छक्तिरेवात्र गुणशब्देन विवक्षिता ॥ स एव पृच्छति—**किं पुनरिति ?** ॥

(उद्द्योतः) प्रयोजनं वदन् विचारस्य प्रकृते संगतिमाह—**यदि द्रव्यमिति** । अत्र **द्रव्यमित्यस्य** शक्त्यनाविष्टं द्रव्यमित्यर्थः ॥

(समाधानभाष्यम्)

गुण इत्याह ॥ कथं ज्ञायते ? । एवं हि कश्चित्कंचित्पृच्छति—क देवदत्त इति । स तस्मायाचष्टे—'असौ वृक्षे' इति । कतरस्मिन् ? । यस्तिष्ठतीति । स वृक्षोऽधिकरणं भूत्वान्येन शब्देनाभिसंबध्यमानः कर्ता संपद्यते ॥ द्रव्ये पुनः साधने सति यत्कर्म कर्मैव स्यात्, यत् करणं करणमेव, यदधिकरणमधिकरणमेव ॥

(प्रदीपः) **गुण इत्याहेति** । अयं भावः—यदि द्रव्यं साधनं स्यात्, तदा तस्यैकरूपत्वात्तन्निबन्धनाबाधितप्रत्यभिज्ञाविषयत्वान्नानार्थक्रियाकरणनिबन्धनो व्यपदेशभेदो न स्यात्, दृश्यते चासाविति नानाशक्तिसद्भावावगमः सिद्धः ॥

(उद्द्योतः) ननु वृक्षशब्दोपात्तस्याधिकरणत्वेपि यच्छब्दोपात्तस्य कर्तृत्वं भविष्यति शब्दभेदेन भेदाद् अत आह—**अयं भाव इति** । शब्दभेदमात्रेणार्थभेदासिद्धिरिति भावः ॥ वृक्षे देवदत्तस्तिष्ठति वृक्षं पश्येत्यादौ दोषाच्च ॥ **द्रव्यमिति** । शक्तिरहितं शुद्धद्रव्यमित्यर्थः ॥ **तन्निबन्धनेति** । एकरूपत्वनिबन्धनेत्यर्थः ॥ **नानार्थक्रियेति** । अर्थक्रियानिरूपितभिन्नकारणत्वनिबन्धन इत्यर्थः ॥ **नानाशक्तीति** । एवं च प्रसज्यप्रतिषेधेपि न दोष इति ध्वनितम् । अत्र हि पक्षे अभिहितायां शक्तौ नेत्यर्थः । तत्र या शक्तिरभिहिता तस्यां मा भूत्प्रत्ययः । या त्वनभिहिता तद्बोधनाय स्यादेव प्रत्यय इति बोध्यम् ॥

(प्रत्याख्यानाधिकरणम्)

(१४६५ प्रत्याख्यानप्रतिज्ञाहेतुवार्तिकम् ७)

॥ * ॥ अनभिहितवचनमनर्थकं प्रथमाविधानस्यानवकाशत्वात् १ ॥ * ॥

(भाष्यम्) **अनभिहितवचनमनर्थकम् ॥ किं कारणम् ? । प्रथमाविधानस्यानवकाशत्वात् । अनवकाशा प्रथमा सा वचनाद्भविष्यति ॥**

(प्रदीपः) सूत्रं प्रत्याख्यातुमाह—**अनभिहितवचनमिति** । क्रियते कटः, कृतः कट इत्यादिषु द्वितीयादिनिवारणायानभिहिताधिकारः क्रियते । यदि चात्र द्वितीयादयः स्युस्ततः प्रथमा निरवकाशैव स्यात् । तस्मादनवकाशत्वात् प्रथमैव द्वितीयादीनां बाधिका भविष्यतीति नार्थोऽनभिहिताधिकारेणेत्यर्थः ॥

(उद्द्योतः) सूत्रं प्रत्याख्यातुमिति । एकत्वादयो विभक्त्यर्था इति पक्षेपीत्यर्थः ॥ भाष्ये—**अनवकाशत्वादिति** ॥ नन्वेवं कृतः कट इत्यादावेव, न कटं करोतीत्यादावित्यत्र किं

सिद्धिमकमिति चेत् । न, मात्रग्रहणेनानभिहितविभक्त्यर्थाधिक्ये प्रथमाया अप्रवृत्तेः । कृत इत्यादौ तद्धटकप्रत्ययेनाभिधानेनाधिक्या-भाव इति भावः ॥

(प्रत्याख्यानहेतुबाधकभाष्यम्)

सावकाशा प्रथमा ॥ कोऽवकाशः ? ॥ अकारकम्— वृक्षः प्लक्ष इति ॥

(प्रदीपः) वृक्ष इति । क्रियापदं न श्रूयत इति विभक्त्यन्तराप्राप्तिं मन्यते ॥

(१४६६ प्रत्याख्यानहेतुसाधकवार्तिकम् ८ ॥)

॥ * ॥ अवकाशोऽकारकमिति चेन्नास्ति-र्भवन्तीपरः प्रथमपुरुषोऽप्रयुज्यमा-नोऽप्यस्ति ॥ * ॥

(भाष्यम्) अवकाशोऽकारकमिति चेत् । तन्न । किं कारणम् ? । अस्तिर्भवन्तीपरः प्रथमपुरुषोऽप्रयुज्य-मानोऽप्यस्तीति गम्यते । 'वृक्षः' 'प्लक्षः' अस्तीति गम्यते ॥

(प्रदीपः) अस्तिर्भवन्तीपर इति । ज्ञातं वस्तु परं प्रतिपादयितुं शब्दः प्रयुज्यते, ज्ञानं च सत इति यत्र क्रियाप-दान्तरस्याप्रयोगस्तत्रोत्सर्गतः सत्ताप्रतीतिरित्यस्तीतिक्रिया-पदानुषङ्गात् कर्तरि तृतीयाप्रसङ्गादनवकाशा प्रथमेत्यर्थः ॥

(उद्योतः) अस्तिर्भवन्तीपर इति । प्रथमाया अपि कर्मणि द्वितीयेत्यादिसाहचर्येण क्रियायोग एव प्रवृत्तिरिति भावः ॥ ज्ञानं च सत इति । वृद्धिसत इत्यर्थः ॥

(१४६७ प्रत्याख्यानहेत्वन्तरवार्तिकम् ९ ॥)

॥ * ॥ विप्रतिषेधाद्वा प्रथमाभावः ॥ * ॥

(भाष्यम्) अथ वा द्वितीयादयः क्रियन्ताम्, प्रथमा चेति । प्रथमा भविष्यति विप्रतिषेधेन । द्वितीयादीनामवकाशः—कटं करोति भीष्ममुदारं शोभनं दर्शनीयमिति । प्रथमाया अवकाशः —अकारकं वृक्षः प्लक्ष इति । इहोभयं प्राप्नोति— कृतः कटो भीष्मः उदारः शोभनो दर्शनीय इति । प्रथमा भविष्यति विप्रतिषेधेन ॥

(प्रदीपः) विप्रतिषेधाद्वेति । सावकाशत्वमभ्युपगम्ये-दमुच्यते ॥

(उद्योतः) अनवकाशत्वमुक्त्वा विप्रतिषेधोपन्यासोऽसंगत इत्यत आह—सावकाशत्वमभ्युपगम्येति । नीलमिदं न तु रक्तमित्यादौ रक्तत्वादिनिवृत्तिपरे वाक्ये सत्ताया अनावश्यकत्वा-दस्तिर्भवन्तीपर इत्यस्याभावात् । साहचर्यं च सर्वत्र न व्यवस्था-पकमित्यभिमानः ॥ वैतण्डिकोक्तिरियमिति तात्पर्यम् ॥ अनेन वस्तुतो निरवकाशत्वमेवेति सूचितम् । उक्तरीत्या तत्रापि सत्ता-क्षेपात् ॥ अत एव तिङ्समानाधिकरणे प्रथमेति न्यासः संगच्छत इति बोध्यम् । स्पष्टं चेदं प्रातिपदिकार्थसूत्रे भाष्ये ॥

(हेत्वन्तरबाधकभाष्यम्)

न सिध्यति । परत्वात् षष्ठी प्राप्नोति ॥

(प्रदीपः) षष्ठीति । क्रियाकारकसंबन्धसद्भावात् ॥

(हेत्वन्तरभाष्यम्)

शेषलक्षणा षष्ठी अशेषत्वान्न भविष्यति ॥

(प्रदीपः) अशेषत्वादिति । प्रातिपदिकार्थस्य व्यति-रेकाभावात् ॥

(उद्योतः) अशेषत्वादिति । अभिहितः सोऽर्थोऽन्त-र्भूतः प्रातिपदिकार्थः संपन्न इत्यनेकमिति सूत्रोक्तरीत्या प्राति-पदिकार्थत्वेन प्रातिपदिकार्थकारकव्यतिरिक्तत्वरूपशेषत्वाभावादिति भावः ॥

(१४६८ प्रत्याख्याननिराकरणवार्तिकम् १० ॥)

॥ * ॥ कृत्प्रयोगे तु परं विधानं षष्ठ्या-स्तत्प्रतिषेधार्थम् ॥ * ॥

(भाष्यम्) कृत्प्रयोगे तु परत्वात्षष्ठी प्राप्नोति । तत्प्रतिषेधार्थमनभिहिताधिकारः कर्तव्यः । कर्त-व्यः कट इति ॥

स कथं कर्तव्यः ? ।

यथैकत्वादयो विभक्त्यर्थाः ॥ अथ हि कर्मादयो विभक्त्यर्थाः नार्थोऽनभिहिताधिकारेण ॥ अनभिहि ॥ १ ॥

(प्रदीपः) कर्तव्यः कट इति । प्रथमां परत्वाद् बाधित्वा कर्तृकर्मणोः कृतीति षष्ठी प्राप्नोति इति तद्बाध-नार्थोऽनभिहिताधिकारः ॥ १ ॥

(उद्योतः) षष्ठी प्राप्नोतीति । न च कृत्यानामिति विभक्तेन षष्ठीनिषेधात्कथं तत्प्राप्तिः । न च नाप्रोभयप्राप्तिः । तदधिकाराभावेनोभयप्राप्तेरपि सत्त्वादिति वाच्यम् । एकसूत्रपक्षे दोषात् । योगविभागस्तु भाष्यकृता वक्ष्यते, न वार्तिककारेण ॥ यथैकत्वादय इति । प्राधान्येन विभक्त्योक्त्या संख्यैव, कारकं तद्विशेषणत्वेन, तदेदं सूत्रं कार्यमित्यर्थः । एवमग्रेपि व्याख्येयम् । उक्तार्थानामिति न्यायः शास्त्रोपात्तप्रधानार्थविषय एव, कारकस्य प्राधान्येन तत्त्वे तु व्यर्थम् ॥ ननु तथापि द्योतकसमावेशस्य दृष्टत्वात् कृतः कट इत्यादौ क्रियते कट इत्यादौ च तद्वारणाय स आवश्यक इति चेन्न । आद्ये विशेष्यत्वेन भानेन तस्य द्योत्यत्वासंभवात् । अन्त्ये-क्रियां प्रति तस्य विशेषणत्वेपि कटपदार्थे सत्त्वाभावेन तदुत्तरद्वि-तीयाद्योत्यताया असंभवाच्चेति दिक् ॥ १ ॥

२९४ द्वितीयानियमसूत्रम् ॥२।३।१ आ. २॥

४६० कर्मणि द्वितीया ॥२।३।२॥

(शेषपूरणाधिकरणम्)

१४६९ द्वितीयाविधायकवार्तिकम् ॥ १ ॥

॥ * ॥ समयानिकषाहायोगेषूपसंख्यानम् ॥ * ॥

(भाष्यम्) समयानिकषाहायोगेषूपसंख्यानं कर्तव्यम् । समया—समया ग्रामम् । समया ॥ निकषा—निकषा ग्रामम् । निकषा ॥ हायोगे—हा देवदत्तम्, हा यज्ञदत्तम् ॥

(प्रदीपः) कर्मणि ॥२॥ समया ग्राममिति । सामीप्यसंबन्धे षष्ठ्यां प्राप्तायां द्वितीयाविधिः । एवं निकषायोगे । हाशब्दः शोकादिवृत्तिरिति तद्योगे षष्ठ्येव प्राप्नोति ॥ [हा तातेत्यादौ त्वन्तरङ्गत्वात् संबोधनविभक्तिरेव भवति ॥]

(उद्द्योतः) कर्मणि ॥२॥ सामीप्यसंबन्धे इति । समयाशब्दशक्यस्यापि सामीप्यस्य तत्प्रधानार्थनिरूपितं संबन्धत्वमपि । यथा राज्ञः स्वमित्यत्र स्वत्वस्येति भावः । सामीप्यानन्तर्यादीनां न षष्ठ्यर्थत्वमिति तु समभिव्याहृतपदार्थभिन्नसामीप्यादिपरम् ॥ [संबोधनेति । संबोधनविभक्तेः पदान्तरानपेक्षत्वादित्यर्थः ॥]

(भाष्यम्) अपर आह—

(१४७० द्वितीयाविधायकवार्तिकान्तरम् ॥ २)

॥ * ॥ द्वितीयाविधानेऽभितःपरितःसमयानिकषाध्यधिधिग्योगेषूपसंख्यानम् ॥ * ॥

(भाष्यम्) द्वितीयाविधानेऽभितःपरितःसमयानिकषाऽध्यधिधिग्योगेषूपसंख्यानं कर्तव्यम् । अभितो ग्रामम् । अभितः ॥ परितो ग्रामम् । परितः ॥ समया ग्रामम् । समया ॥ निकषा ग्रामम् । निकषा ॥ अध्यधि ग्रामम् । अध्यधि ॥ धिग्जाल्मम् । धिग् वृषलम् । धिग् ॥

(प्रदीपः) अभितो ग्राममिति । पर्यभिभ्यां चेति तसिलन्तावभितःपरितःशब्दावुभयतःसर्वतइत्यनयोरर्थयोर्वर्तेते। तद्योगे षष्ठ्येव प्राप्नोति । आभिमुख्यवृत्तिरपि विभक्तिप्रतिरूपको निपातोभितःशब्दोस्ति सोपीह गृह्यते तद्योगेऽपि षष्ठी प्राप्नोति ॥ अध्यधि ग्राममिति । उपर्यध्यधसः सामीप्य इति द्विर्वचनम् । अधिशब्दोत्रोपर्यर्थे वर्तते इति षष्ठी प्राप्नोति ॥ धिग् जाल्ममिति । धिक्शब्दस्य निन्दार्थत्वात्तद्योगे षष्ठ्याः प्राप्तिः ॥

(उद्द्योतः) उपर्यर्थेवर्त्ततेइति । उपरिसामीप्ये वर्तत इत्यर्थः ॥

(भाष्यम्) अपर आह—

(१४७१ द्वितीयाविधायकवार्तिकान्तरम् ३ ॥)

उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु ।
द्वितीयाम्रेडितान्तेषु ततोन्यत्रापि दृश्यते ।

उभसर्वइत्येताभ्यां तसन्ताभ्यां योगे द्वितीया वक्तव्या । उभयतो ग्रामम् । सर्वतो ग्रामम् ॥ धिग्योगे—धिग् जाल्मम् धिग् वृषलम् ॥ उपर्यादिषु त्रिष्वाम्रेडितान्तेषु द्वितीया वक्तव्या । उपर्युपरि ग्रामम् । अध्यधि ग्रामम् । अधोधो ग्रामम् ॥ ततोन्यत्रापि दृश्यते । न देवदत्तं प्रति भाति किंचित् । बुभुक्षितं न प्रति भाति किंचित् ॥ कर्मणि द्वि ॥ २ ॥

(प्रदीपः) उभसर्वतसोरिति । उभसर्वयोस्तसाविति षष्ठीसमासः । उभयशब्दावयवस्योभशब्दस्यानुकरणमुभशब्द इत्युभयशब्दो गृह्यते द्विवचनटाब्विषयत्वादुभशब्दस्य तसन्तस्याभावात् ॥ दृश्यत इति । दृशिग्रहणं प्रयोगानुसरणार्थम्॥ न देवदत्तं प्रतीति । षष्ठ्यत्र प्राप्नोति । प्रतिशब्दश्चात्र क्रियाविशेषक उपसर्गो न तु कर्मप्रवचनीय इत्युदाहृतम् । केनचित् किंचित्स्मृतमिति दर्शनायानेकस्मृत्युपन्यासः ॥ २ ॥

(उद्द्योतः) उभसर्वइत्येताभ्यामिति भाष्यस्य एतत्प्रकृतिकाभ्यामित्यर्थः ॥ उभशब्दात्तसोनुत्पत्त्यास्यायुक्तत्वं परिहरन्नुक्तस्यार्थस्य वार्त्तिकाद्यथा लाभस्तथा दर्शयति—उभसर्वयोरिति । ननु वृत्तिविषये पूर्वमेवायचः प्रवृत्तेरुभप्रकृतिकत्वं न तस इत्यत आह—उभयेति । उभेति । तद्घटितोभयशब्दलाक्षणिकमिति भावः ॥ ननु कर्मप्रेति । अन्यथा कर्मप्रवचनीययुक्ते इत्येवसिद्धं स्यादित्यर्थः ॥ २ ॥

(२९५ द्वितीयातृतीयासूत्रम् ॥२।३।१ आ. ३॥)

४६१ तृतीया च होश्छन्दसि ॥२।३।३॥

(उद्द्योतः) तृतीया च ॥ ३ ॥ अस्योदाहरणेऽग्निहोत्रशब्दो हविःपरस्तत्र द्वितीया तत्समानाधिकरणयवागूशब्दादनेन तृतीयापि । विरुद्धविभक्त्य[र्थी]नयन्द्धत्वाच्च सामानाधिकरण्यमिति सूत्रमतम्, भाष्यमतं च ॥ एवंतर्हि तृतीयापि सिद्धेत्यादेर्भाष्यस्योक्तिप्रत्युक्तिक्रमेण पूर्वपक्ष्युक्तित्वात् ॥

(प्रयोजनाधिकरणम्)

(प्रत्याख्यानायपूर्वपक्षिणआक्षेपभाष्यम्)

किमर्थमिदमुच्यते ? ।

(प्रदीपः) तृतीया च ॥ ३ ॥ किमर्थमिति । अन्तरेणाप्येतत्सूत्रं द्वितीयातृतीये सिद्धे इति प्रश्नः ॥

(सिद्धान्तिनःसूत्रप्रयोजनभाष्यम्)

तृतीया यथा स्यात् ॥

(प्रदीपः) तृतीयेति । देवतोद्देशेनाग्नौ हविःप्रक्षेपो जुहोत्यर्थस्तत्र यवाग्वा द्वितीया प्राप्नोति तृतीया विधीयते ॥

(उद्योतः) ननु जुहोतेः प्रीणात्यर्थत्वेऽग्निहोत्रशब्दस्याग्न्यर्थत्वे करणत्वात् तृतीयासिद्धिमाशङ्क्याह—देवतेति ॥ अग्निहोत्रशब्दो हविःपरः । तद्विशेषणं यवागूरिति भावः ॥ यद्यपि अग्नौ हविरिति चिन्त्यं यदे जुहोति अग्नौ जुहोतीत्यादिश्रुतिविरोधात् । तस्मादधे आधारे प्रक्षेप इत्येव युक्तम्, तथापि प्रकृताभिप्रायमेतत् । तत्र यवाग्वाः कर्मत्वाद् द्वितीया प्राप्तेत्यर्थः ॥

(पूर्वपक्षिणआक्षेपभाष्यम्)

अथ द्वितीया सिद्धा ? ।

(प्रदीपः) अथ द्वितीयेति । किमप्राप्ता द्वितीया चकारेण विधीयते अथ तृतीयया मा बाधीति पक्षे चकारेणाभ्यनुज्ञायत इति प्रश्नः ॥

(उद्योतः) चकारेण द्वितीयाविधानात् प्रश्नानुपपत्तिमाशङ्क्याह—किमप्राप्तेति ॥

(सिद्धान्तिनः समाधानभाष्यम्)

सिद्धा ॥ कथम् ? । 'कर्मणि' इत्येव ॥

(पूर्वपक्षिणः सूत्रवैयर्थ्यभाष्यम्)

तृतीयापि सिद्धा ॥ कथम् ? । * सुपां सुपो भवन्ति * इत्येव ॥

(सिद्धान्तिनःसूत्रसार्थक्यभाष्यम्)

असत्येतस्मिन्—* सुपां सुपो भवन्ति * इति तृतीयार्थोयमारम्भः । यवाग्वाग्निहोत्रं जुहोति ॥

(प्रदीपः) असत्येतस्मिन्निति । न हि पाणिनेः सूत्रकरणकाले कात्यायनवचनस्य भावः ॥

(उद्योतः) प्रयोजनान्तरसिद्धये तस्यावश्यकत्वाद् असत्येतस्मिन्नित्ययुक्तमत आह—नहीति । एवं च युक्तावसति तस्मिन्नुपायान्तरपरमिति भावः ॥

(एकदेशिनः पूर्वपक्षिणो वा प्रत्याख्यानभाष्यम्)

एवं तर्हि तृतीयापि सिद्धा ॥ कथम् ? । "कर्तृकरणयोः" इत्येव ॥ अयमग्निहोत्रशब्दोस्त्येव ज्योतिषि वर्तते । तद्यथा—अग्निहोत्रं प्रज्वलितमिति ॥ अस्ति हविषि वर्तते । तद्यथा—अग्निहोत्रं जुहोतीति ॥ जुहोतिश्चास्त्येव प्रक्षेपणे वर्तते । अस्ति प्रीणात्यर्थे वर्तते ॥ तद्यदा तावद्यवागूशब्दात्तृतीया, तदाग्निहोत्रशब्दो ज्योतिषि वर्तते, जुहोतिश्च प्रीणात्यर्थे । तद्यथा—'यवाग्वाग्निहोत्रं जुहोति' अग्निं प्रीणाति ॥ यदा यवागूशब्दाद् द्वितीया तदाग्निहोत्रशब्दो हविषि वर्तते जुहोतिश्च प्रक्षेपणे । तद्यथा—'यवागूमग्निहोत्रं जुहोति' यवागूं हविरग्नौ प्रक्षिपति ॥ तृतीया च ॥ ३ ॥

(प्रदीपः) अग्निहोत्रमिति । अग्निर्ज्योतिरित्यर्थः ॥ अग्निं प्रीणातीति । अग्निषु हूयमानेष्विति प्रीणात्यर्थे जुहोतेः प्रयोगदर्शनात् ॥ ३ ॥

(उद्योतः) एवं तर्हि तृतीयापीत्यादि भाष्यं पूर्वपक्ष्युक्तिः । अर्थभेदात्मा न युक्तेति स्फुटत्वाद् भाष्ये नोक्तम् ॥ अग्निष्विति बहुवचनेन सामानाधिकरण्यावगतेर्धात्वन्तरासम्भवात्प्रीणात्यर्थत्वमित्यर्थः ॥ यत्तु मीमांसका अग्निहोत्रशब्दस्य कर्मनामधेयत्वं तत्प्रख्यन्यायात् स एव यज्ञः पञ्चविधोग्निहोत्रं दर्शपूर्णमासाविति दर्शनाच्च । एवं च करणभूते होमे समानाधिकरणस्याग्निहोत्रस्य करणत्वात् तृतीयायां प्राप्तायां पक्षे द्वितीयार्थमिदम् । यवाग्वा अपि करणत्वादेव तृतीया सिद्धेति ॥ तन्न सूत्रानुगुणम्, नापि भाष्यानुगुणं कर्मणीत्यनुवृत्तेः । पाणिनीयस्मृतेर्वचनरूपत्वेन जैमिनीयाया न्यायरूपत्वेन तद्बाधकताया अत्यान्युचितत्वाच्च । एवं च यवाग्वाग्निहोत्रं जुहोतीत्यादिवाक्ये नामधेयत्वाभावः । अत एव यवागूमग्निहोत्रं जुहोतीत्यादिसिद्धिरिति दिक् ॥ ३ ॥

(२९६ द्वितीयासूत्रम् ॥२।३।१ आ. ४॥)

४६२ अन्तरान्तरेण युक्ते ॥२।३।४॥

(अन्तरेणेतिशब्दार्थनिर्णयाधिकरणम्)

(आक्षेपभाष्यम्)

इह कस्मान्न भवति—किं ते बाभ्रवशालङ्कायनानामन्तरेण गतेनेति ? ॥

(प्रदीपः) अन्तरा ॥४॥ अन्तरेण गतेनेति । अन्तरशब्दोत्र विशेषवाची । विशेषेण ज्ञातेन किं ते प्रयोजनमिति वाक्यार्थः ॥

(उद्योतः) अन्तरान्त ॥४॥ अन्तरेणेति तृतीयान्ताभिप्रायेण प्रश्न इत्याह—अन्तरेति । गतशब्दो ज्ञातार्थक इति भावः ॥

(समाधानभाष्यम्)

'लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्' इति ॥

अथ वा यद्यपि तावदयमन्तरेणशब्दो दृष्टापचारो निपातश्चानिपातश्च । अयं तु खल्वन्तराशब्दोऽदृष्टापचारः निपात एव । तस्यास्य

कोन्यः सहायो द्वितीयो भवितुमर्हति—अन्यवतो निपातात् । तद्यथा—अस्य गोर्द्वितीयेनार्थ इति गौरेवानीयते, नाश्वो न गर्दभः ॥

(प्रदीपः) **लक्षणप्रतिपदोक्तयोरिति** । तृतीयान्तो लाक्षणिकः, विभक्तिप्रतिरूपकस्तु निपातः प्रतिपदोक्तः ॥ **दृष्टापचार इति** । दृष्टव्यभिचारः । अनिपातस्यापि भावात् ॥ **अन्तराशब्द इति** । नन्वन्तराशब्दोऽप्यनिपात आवन्तोऽस्ति अन्तरायां पुरि वसतीति तत्कथमसावदृष्टा—पचारः ॥ एवं तर्हि टावन्तस्य लाक्षणिकत्वात् स्त्रीत्वापेक्षटा-बाश्रयत्वाद्बहिरङ्गत्वाच्चाग्रहणं मन्यते ॥ अथ वा परस्परसाह-चर्यान्निपातयोर्ग्रहणमिति वाच्यम् ॥

(उद्द्योतः) **बहिरङ्गत्वादिति** । अर्थकृतबहिरङ्गत्वस्य शास्त्रे-नाश्रयणाच्चिन्त्यमिदम् ॥ लाक्षणिकत्वेन परिहारे तेनैवान्तरेणेत्यस्य व्यावृत्तौ भाष्यानुपपत्तिस्तदवस्था पूर्वस्मादविशेषश्चेत्यत आह— **अथवेति** । साहचर्यमत्र सादृश्यम् ॥ **कोन्यः सहाय** इति भाष्ये **प्रयोगे** इति शेषः । यथा कार्ये सदृशस्यैव सहायत्वं तथा प्रयोगे-पीति भावः ॥ **परस्परेति** । अन्तरासाहचर्यादन्तरेणेत्यतृतीयान्तं तत्साहचर्यात्तदटावन्तमेवेति निपातयोरेव ग्रहणसिद्धिरिति भावः ॥ न च परस्परसाहचर्यादनव्यययोरेव ग्रहणं कुतो नेति वाच्यम् । व्याख्यानात् ॥ यत्तु—अव्यययोः स्वरादौ चादौ वा पाठेन परस्पर-साहचर्यसंभवेप्यनव्यययोः पाठाभावात्साहचर्यस्य वक्तुमशक्यत्वा-दिति । तन्न, उक्तभाष्येण सादृश्यस्य सहप्रयोगे नियामकताया उक्तत्वात् ॥ वस्तुतस्तु युक्तग्रहणात् संम्बन्धिनि नित्यसा-काङ्क्षयोरेवैतयोर्ग्रहणम् । न च टावन्तमन्तराशब्दस्तथा, अनावृतदे-शत्वेन परिधानीयत्वेनैव च तेन बोधादिति भाष्याशयः ॥ **अस्य-गोर्द्वितीयेनेति** । द्वितीयशब्दोऽत्र सहायवाची ॥

(१४७२ वार्तिकम् ॥ १ ॥)

॥ * ॥ अन्तरान्तरेणयुक्तानामप्रधानवचनम् ॥ * ॥

(भाष्यम्) **अन्तरान्तरेणयुक्तानामप्रधानग्रहणं कर्त्तव्यम् । अप्रधाने द्वितीया भवतीति वक्तव्यम् । अन्तरा त्वां मां च कमण्डलुरिति कमण्डलोर्द्वितीया मा भूदिति ॥**

(प्रदीपः) **अप्रधान इति** । युष्मदस्मदर्थस्य विशेषणत्वादप्राधान्यं कमण्डलोस्तु विशेष्यत्वात्प्रधानता ॥

(आक्षेपभाष्यम्)

कः पुनरेताभ्यां कमण्डलोर्योगः ? ।

(प्रदीपः) **कः पुनरिति** । अन्तरान्तरेणशब्दाभ्यामाश्रयप्रधानमध्यवचनाभ्यां युष्मदस्मदर्थस्यैवावधेर्योगो न तु कमण्डलोरिति मत्वा प्रश्नः ॥

(उद्द्योतः) मध्ये इत्यर्थकेनान्तरेणेत्यादिना कमण्डलोरपि योगात् प्रश्नानुपपत्तिरत आह—**अन्तरेति** । अन्तरेत्यादेर्मध्यवर्तीत्यर्थः ॥ **नतु कमण्डलोरिति** । अभेदस्य सत्त्वेपि तस्य षष्ठीप्रयोजकत्वाभावेन तदपवादविभक्तिप्रयोजकत्वमपि नेति भावः ॥

(समाधानभाष्यम्)

यत्त्वां च मां चान्तरा तत्कमण्डलोः स्थानम् ।

(प्रदीपः) **यत्तदिति** । मध्य इत्येतस्मिन्नर्थे तयोर्वर्तनादवधेरपि ताभ्यां योगोऽस्ति आधारार्थत्वादाधेयस्य कमण्डलोः ॥ **अन्तरा तदिति** । अत्र भाष्यकारेण मध्यमात्र-वचनोन्तराशब्दः प्रयुक्तो न त्वाधाररूपमध्यवाची । अन्यथा तत्स्थानमिति सामानाधिकरण्यं न स्यात् । कमण्डलुयोगप्रतिपादनाय चैवं प्रयोगः । लौकिके तु प्रयोगे मध्यइत्युद्भूताधारशक्तिके मध्येन्तराशब्दो वर्तते ॥

(उद्द्योतः) **आधारार्थत्वादिति** । आधारस्य तत्त्वादित्यर्थः । तस्य तत्परतन्त्रत्वे समानन्यायेनाधेयपरतन्त्र आधार इति कमण्डलोरपि तद्योग इति भावः ॥ **नत्वाधाररूपेति** । आधारशक्तिप्रधानेत्यर्थः ॥ **तत्स्थानमिति** । अन्यथा तत्र स्थानमिति वक्तव्यं स्यादिति भावः ॥ **कमण्डलुयोगेति** । अत्यन्तभेदप्रतिपादनद्वारेत्यर्थः ॥ **उद्भूताधारेति** । तस्य चाधेये आधाराधेयभावेनैवान्वये साधुत्वं न तु केनचिदभेदान्वये इति भावः ॥

(आक्षेपभाष्यम्)

तत्तर्हि वक्तव्यम् ? ॥

(समाधानभाष्यम्)

न वक्तव्यम् ।

कमण्डलोर्द्वितीया कस्मान्न भवति ? ।

'उपपदविभक्तेः कारकविभक्तिर्बलीयसी' इति प्रथमा भविष्यति ॥ अन्तरान्तरे ॥ ४ ॥

(प्रदीपः) **उपपदविभक्तेरिति** । अस्तीति क्रियानुषङ्गात्कमण्डलोः कर्तृत्वम् । तच्च तिङाभिहितमिति प्रथमा कारकविभक्तिः । सा चान्तरङ्गा क्रियाकारकयोः संबन्धस्यान्तरङ्गत्वात् । उपपदार्थेन तु क्रियाद्वारकः संबन्ध इति तन्निमित्ता बहिरङ्गा विभक्तिः ॥ ४ ॥

(उद्द्योतः) **उपपदविभक्तेरिति** न्यायमूलकम्, न वाचनिकमित्याह—**सा चेति** ॥ **क्रियाद्वारक इति** । सर्वत्र संबन्धस्य किञ्चित्क्रियाकारकभावमूलत्वाद् यथा स्वत्वं क्रयादिनिबन्धनमिति भावः ॥ युक्तिरत्र शिथिला सर्वत्र प्रथमाया एवापत्तेर्युष्मदाद्यर्थेपि सत्ताकर्तृत्वस्याव्यभिचारात् । न चैवं सूत्राणां वैयर्थ्यं न्यायानुगतेर्वै किं कुर्मः । तस्माद्वचनमेवेदम् । अत एव नमस्यति देवानित्यत्रानेन न्यायेन द्वितीयां वक्ष्यति भाष्यकृत् । तत्र हि क्रियाकारकभावेनैवान्वयादित्यन्ये ॥ न च विशेषणे संबन्धस्योद्भूततया प्रतीतेस्तत्रैव षष्ठ्यपवादत्वेन सम्बन्धाधिकैव द्वितीयेति वाच्यम् । प्रथमापवाद-

त्वस्यापि सम्भव इत्याशयात् । उपपदविभक्तेरिति वचनात्तु पदवचपवादत्वमेव न प्रथमापवादत्वमित्युत्तराशयः । प्रथमाया अपि कारकविभक्तित्वं क्रियाजनकेर्थे तस्या अपि विधानादिति बोध्यम् । तदुक्तम्—कमण्डलोः कर्तृत्वं तिङाभिहितमिति ॥ ४ ॥

(कालवाचकाध्ववाचकाभ्यां विभक्तिनियमप्रकरणम्)

(२९७ द्वितीयासूत्रम् ॥ २ । ३ । १ आ. ५)

४६३ कालाध्वनोरत्यन्तसंयोगे॥२।३।५॥

(कालाध्वनोरुक्ततया प्रथमासाधनाधिकरणम्)

(१४७३ वार्तिकम् ॥ १ ॥)

॥*॥ अत्यन्तसंयोगे कर्मवल्लाद्यर्थम् ॥*॥

(भाष्यम्) अत्यन्तसंयोगे कालाध्वानौ कर्मवद्भवत इति वक्तव्यम् । किं प्रयोजनम् ? । लाद्यर्थम् । लादिभिरभिधानं यथा स्यात्—[लादिभिरभिहिते द्वितीया मा भूत्] आस्यते मासः, शय्यते क्रोशः ॥

अथ वत्करणं किमर्थम् ? । स्वाश्रयमपि यथा स्यात्—आस्यते मासम्, शय्यते क्रोशम्, अकर्मकाणां भावे लो भवतीति भावे लो यथा स्यात् ॥

(प्रदीपः) कालाध्वनोः ॥ ५ ॥ पाणिनीये सूत्रन्यासे सति मासमास्यते देवदत्तेनेति भाव एव लादयः स्युर्न तु कर्मणि । ततश्चास्यते मासः, आसितो मासः, आसितव्यो मासः स्वासो मास इति प्रयोगानुपपत्तिरिति वार्तिकारम्भः—अत्यन्तसंयोग इति । अनत्यन्तसंयोगे तु अधिकरणसप्तम्येव भवति—अमावास्यायां यजत इति ॥ लाद्यर्थमिति । आदिशब्देन निष्ठादीनां ग्रहणम् । तथा चोदाहृतम् । कर्मातिदेशेनैव च मासमास्ते देवदत्त इति द्वितीयायाः सिद्धत्वात्तदर्थः सूत्रेणेति भावः ॥ स्वाश्रयमपीति । यथा ब्राह्मणवदस्मिन् क्षत्रिये वर्तितव्यमिति ब्राह्मणकार्याणि क्षत्रिये क्रियन्ते न तु स्वाश्रयाणि निवर्त्यन्ते, तद्वदत्रापि कर्मकार्याणि अतिदिश्यन्ते न स्वाश्रयाणि निवर्त्यन्ते ॥ यद्येवमन्तरेणापि वतिं स्वाश्रयाणि कार्याणि भविष्यन्ति ॥ नैतदस्ति । स्वाश्रयकार्यनिवृत्तये तद्रूपासङ्ग आशङ्क्येत ॥

(उद्योतः) कालाध्वनोः ॥ ५ ॥ लाद्यर्थमित्युत्तरं लादिभिरभिधानं यथा स्यादिति भाष्ये पाठमभिप्रेत्याह—ननु कर्मणीति । अकर्मकधातुभिर्योग इति तु न विधायकमिति प्रागेव निरूपितम् ॥ लाद्यर्थमित्युत्तरं भाष्ये पाठान्तरं लादिभिरभिहिते द्वितीया मा भूदिति ॥ तत्रयुक्तम्, प्रकारान्तरेण लप्राप्तेरभावात् ॥ नन्विदं वार्तिकं सकर्मकाकर्मकविषयम्, अकर्मकविषयं वा । नाद्यः । मासं पठति वेदं देवदत्त इत्यादौ मासादिकर्मण्यपि लाद्यापत्तौ मासः पठ्यते वेदं देवदत्तेनेत्यादिप्रयोगापत्तेः । नान्त्यः । सङ्कोचे मानाभावात् । सकर्मकार्थं कालाध्वनोरित्यस्यावश्यकत्वेन न तर्हीदानीमिदं सूत्रं कर्तव्यमिति भाष्यविरोधापत्तेश्चेति चेद् ॥ उच्यते—सर्वविषयं वार्तिकम्, सूत्रं च न कार्यमित्येव तात्पर्यम् । न च मासः पठ्यते वेदं देवदत्तेनेत्यस्यापत्तिः । उभयसन्निधौ अन्तरङ्गे मुख्ये च द्रव्यकर्मण्येव लप्रवृत्तिरिति न दोषः । द्रव्यकर्मणोन्तरङ्गत्वं च धात्वन्तरार्थानन्तर्भावार्थकर्मत्वेन ॥ वार्तिकप्रामाण्येन गौणे कर्मणि दुह्यादेरित्यादिवद् भाष्यप्रामाण्येनाप्येवंविधकल्पनाश्रयणाच्च । एवं च प्राकृतमेवेति पक्षेपि न दोषः । अत्र पक्षे आस्यते मास इति कर्मणि ले यत्राक्रियेति वक्ष्यमाणरीत्याऽवश्यकेनाप्यनेन द्वितीया तु न, अत्यन्तसंयोगस्य व्याप्तिरूपस्य धातुनोक्तत्वात् ॥ यद्येवमिति । अकर्मणि कर्मशब्दप्रयोगेण वत्यर्थावगतौ अतिदेशस्वाभाव्यादेव स्वाश्रयसिद्धेरिति भावः ॥ तद्रूपासङ्ग इति । कर्मशब्दरूपस्यासङ्गः सम्बन्धः संज्ञात्वमित्यर्थः ॥

(आक्षेपभाष्यम्)

तत्तर्हि वक्तव्यम् ? ।

(समाधानभाष्यम्)

न वक्तव्यम् । प्राकृतमेवैतत् कर्म । यथा कटं करोति शकटं करोतीति ॥

(प्रदीपः) प्राकृतमेवेति । सकर्मकव्यापनादिधात्वर्थाङ्गे आसनादावास्यादीनां वर्तनात् स्वाभाविकमेतत् कर्मेत्यर्थः । ततश्च मासमास्त इत्यस्य मासमासनेन व्याप्नोतीत्यर्थः । नियतत्वाच्च प्रयोगस्य कट आस्त इत्यादौ आसनमात्रेऽनङ्गीकृतक्रियान्तरे आसिर्वर्तत इति अतिप्रसङ्गो नोद्भावनीयः ॥

(उद्योतः) धात्वर्थाङ्गे इति । आसनपूर्वके व्यापने धातोर्वृत्तिरित्यर्थः ॥ नन्वनया रीत्या कटमास्त इत्यपि स्यादत आह—नियतत्वाच्चेति ॥

(एकदेशिभाष्यम्)

एवं मन्यते—यत्र कश्चित्क्रियाकृतो विशेष उपजायते, तन्न्याय्यं कर्मेति । न चेह कश्चित्क्रियाकृतो विशेष उपजायते ॥

(प्रदीपः) किमर्थं वार्तिककारेणातिदेश आरब्ध इत्याह—एवं मन्यत इति ॥ यत्र कश्चिदिति । यथा काण्डानि लुनातीत्यादौ ॥

(उद्योतः) भाष्ये एकदेशी वार्तिकाशयमाह—एवं मन्यते इत्यादिना ॥

(सिद्धान्तिभाष्यम्)

नैवं शक्यम् । इह हि दोषः स्यात्—आदित्यं पश्यति, हिमवन्तं शृणोति, ग्रामं गच्छतीति । तस्मात्प्राकृतमेवैतत्कर्म । यथा—कटं करोति, शकटं करोतीति ॥

(प्रदीपः) आदित्यमिति । न हि दर्शनक्रिययादित्ये

प्रत्यक्षानुमानसमधिगम्यः कश्चिद्विशेष उत्पाद्यते । केवलं दर्शनक्रिययाप्तुमिष्टतमत्वादादित्यः कर्म तद्वन्मासमास्त इति मासोपीत्यर्थः ॥

(उद्द्योतः) तद्दूषयति—नैवं शक्यमिति ॥

(आक्षेपभाष्यम्)

यदि तर्हि प्राकृतमेवैतत्कर्म, 'अकर्मकाणां भावे लो भवतीति भावे लो न प्राप्नोति—आस्यते मासं देवदत्तेनेति ? ॥

(उद्द्योतः) पुनर्वार्त्तिकारम्भ आवश्यक एवमपीत्याशङ्कते—यदि तर्हीत्यादिना ॥

(तृतीयाक्षेपभाष्यम्)

तत्तर्हि वक्तव्यम् ? ॥

(उद्द्योतः) तर्हि तद्वक्तव्यं कर्मवदिति यदुक्तं तदित्यर्थः ॥

(समाधानभाष्यम्)

न वक्तव्यम् । अकर्मकाणामित्युच्यते । न च केचित्कालभावादिभिरकर्मकाः । त एवं विज्ञास्यामः—'क्वचिद्ये अकर्मका' इति ॥

अथ वा 'येन कर्मणा सकर्मकाश्चाकर्मकाश्च भवन्ति तेनाकर्मकाणाम्' न चैतेन कर्मणा कश्चिदप्यकर्मकः ॥

अथ वा 'यत्कर्म भवति, न च भवति, तेनाकर्मकाणाम्' न चैतत्कर्म क्वचिदपि न भवति ॥

(प्रदीपः) न च केचिदिति । यद्यपि क्रियामात्रप्रतिपादने कालादीनामभावात्तदभावनिबन्धनमपि संभवत्यकर्मकत्वं तथापि धातूनामन्यपदार्थत्वेनाश्रयणात् तेषां प्रयोगान्तरे तदर्थानामेव कालादिसंबन्धदर्शनात्तैरकर्मकत्वासंभवात्सामर्थ्याद्विशेषाङ्गीकरणमिति द्रव्यकर्मणाकर्मकत्वं विज्ञायत इत्यर्थः ॥ **क्वचिदिति** । द्रव्य इत्यर्थः ॥ **अथ वेति** । अन्तरङ्गत्वाद् द्रव्यकर्मणो वहिरङ्गस्य कालादेस्तिरोभावात्तदपेक्षः सकर्मकाकर्मकव्यपदेशो न प्रवर्तत इत्यर्थः ॥ यत्र त्वन्तरङ्गस्यासन्निधिस्तत्र कालादिनिमित्तः सकर्मकव्यपदेशो भवत्येवेत्यास्यते मास इति कर्मणि लकारो भवति ॥ **अथवा यत्कर्मेति** ॥ संभवव्यभिचाराभ्यां विशेषणविशेष्यभावाद् ॥

(उद्द्योतः) उत्तरयति सिद्धान्ती—**न वक्तव्यमिति** ॥ **अकर्मकाणामित्युच्यते इति** । गत्यादिसूत्रे इति शेषः । तत्र योगविभागेन सजातीयापेक्षनियमेन सिद्धे तत्सूत्रेऽकर्मकग्रहणात्कालादिभिन्नकर्मरहितार्थबोधकानामेव शास्त्रेऽकर्मकग्रहणेन ग्रहणमिति बोध्यत इति भावः । अकर्मकग्रहणं सामर्थ्यादत्यन्ताविद्यमानकर्मकग्रहणार्थमेव स्यादत आह—**न चेति** । एवं च तदर्थासम्भव इति भावः ॥ तस्मात्तत्सामर्थ्यान्निषेधप्रतियोगिसमर्पककर्मशब्देन मासादीनामग्रहणं तदाह—**तएवमित्यादि** ॥ **क्वचिदिति** । कालादीनां कर्मत्वप्रयोजकव्याप्त्यादिरहितेर्थे इत्यर्थः । इदं गतिसूत्रे निरूपितम् ॥

यद्यपीति । अकर्मकाणामित्यस्य कर्मानन्वय्यर्थप्रतिपादकानामित्यर्थ इत्यभिप्रायः ॥ **तथापि धातूनामिति** । धातूनामन्यपदार्थत्वात् क्वचित्कर्मस्पर्शेप्यकर्मकत्वहानेः सामर्थ्यान्न विद्यते द्रव्यकर्म येषामिति विग्रह इति भावः । अर्थानामन्यपदार्थत्वेपि भाष्योपपत्तिरुक्तैवेति चिन्त्यम् ॥ **तदर्थानामेवेति** । अधिकार्थे वृत्तावपि तदर्थस्यात्यागादिदमुक्तम् ॥ **द्रव्ये इति** । विषयसप्तमीयम् । सामर्थ्याद् द्रव्यरूपकर्मरहिता इत्यर्थ इति भावः ॥ शिष्टं भाष्यं कैयटश्च गत्यादिसूत्रे व्याख्यातौ । एतद्भाष्यस्य वास्तवार्थोपि तत्रैवोक्तः ॥ ननु तुल्यन्यायेन कालकर्मणा सकर्मकव्यवहारस्याप्यभावे तत्र कर्मणि लो न स्यादत आह—**यत्र स्विति** । तत्संनिधौ तु न तेन व्यवहार इति मासः पठ्यते वेदमिति न प्रयोगः ॥

(सूत्रस्थापनाधिकरणम्)

(आक्षेपभाष्यम्)

न तर्हीदानीमिदं सूत्रं वक्तव्यम् ? ॥

(प्रदीपः) वार्तिकं दूषयित्वा सूत्रं स्थापयितुं पृच्छति—**न तर्हीति** ॥

(उद्द्योतः) तर्कनयैव कल्पनया सर्वत्र द्वितीयादिसिद्धौ सूत्रं न कार्यमिति पृच्छति—भाष्ये—**न तर्हीति** ॥

(समाधानभाष्यम्)

वक्तव्यं च ॥ किं प्रयोजनम् ? । यत्राक्रिययात्यन्तसंयोगः तदर्थम्—क्रोशं कुटिला नदी, क्रोशं रमणीया वनराजिः ॥ कालाध्वनोः ॥ ५ ॥

(प्रदीपः) **क्रोशं कुटिलेति** । गुणेनात्रात्यन्तसंयोगो न तु क्रिययेति कर्मत्वाभावः ॥ ५ ॥

(उद्द्योतः) उत्तरयति—**यत्राक्रिययेति** । न च मासमास्ते इत्यादौ प्राकृतकर्मणः शेषत्वविवक्षायां षष्ठीबाधनार्थं तत्राप्यावश्यकत्वेनाक्रिययेति असंगतम् । क्रियाकारकभावेन यत्रान्वयाभावस्तदर्थमित्यर्थात् ॥ ५ ॥

(२९८ द्वितीयाबाधकतृतीयासूत्रम् ॥२।३।१ आ. ६)

४६४ अपवर्गे तृतीया ॥२।३।६॥

(अनिष्टापत्तिवारणाधिकरणम्)

(१४७४ नियमवार्तिकम् १)

[॥ * ॥ क्रियापवर्गे ॥ * ॥]

(भाष्यम्) **क्रियाऽपवर्ग इति वक्तव्यम् । साधनापवर्गे मा भूद—मासमधीतोनुवाको न चानेन गृहीत इति ॥ अपवर्गे ॥ ६ ॥**

(प्रदीपः) **अपवर्गे** ॥ ६ ॥ अपवर्गो निष्ठा । स कदाचित् फलावाप्तौ सत्यां प्रयोजनाभावात् क्रियाया भवति, कदाचिदशक्त्यादिना साधनानामुपरमाद्भवतीति वार्तिकारम्भः **क्रियापवर्ग इति** ॥ यद्यपि साधनापवर्गे क्रियापवर्गोस्ति

तथापि विशेषणोपादानसामर्थ्याद्विशेष आश्रीयते क्रियाया एव योपवर्गो, न तु साधनानामशक्त्यादिनिमित्तस्तत्रेत्यर्थः ॥ ६ ॥

(उद्द्योतः) अपवर्गे ॥ ६ ॥ निष्ठा समाप्तिः ॥ साधनापवर्गे इति । साधनोपरमकृतक्रियात्यागेपीत्यर्थः ॥ क्रियाया एवेति । स्वत एवेत्यर्थः । स च फलप्राप्तावेव भवतीत्यर्थः । साधने आलस्यादिरहिते सत्यपि प्रयोजनलाभेन क्रियायाः समाप्तिः स क्रियापवर्गः । प्रयोजनालाभेन क्रियाया आवृत्त्यावश्यकत्वेपि आलस्यादिना क्रियातो निवृत्तिः साधनापवर्ग इति भेद इति भावः ॥ ६ ॥

(२९९ सप्तमीपञ्चमीसूत्रम् ॥२।३।१ आ. ७॥)

४६५ सप्तमीपञ्चम्यौ कारकमध्ये ॥ २ । ३ । ७ ॥

(न्यूनतापूर्त्यधिकरणम्)

(१४७५ विवक्षितपूर्ति वार्तिकम् १)

[॥ * ॥ क्रियामध्ये ॥ * ॥]

(भाष्यम्) क्रियामध्य इति वक्तव्यम् । इहापि यथा स्यात्—अद्य देवदत्तो भुक्त्वा द्व्यहाद्भोक्ता, द्व्यहे भोक्ता ॥ कारकमध्य इतीयत्युच्यमाने इहैव स्यात्-इहस्थोयमिष्वासः क्रोशाल्लक्ष्यं विध्यति, क्रोशे लक्ष्यं विध्यति । यं च विध्यति यतश्च विध्यति तयोस्तन्मध्यं भवति ॥

(प्रदीपः) सप्तमी ॥ ७ ॥ अद्य देवदत्त इति । द्रव्यं कारकं तच्चात्रैकमेवेति भेदनिबन्धनो मध्यव्यपदेशो नास्तीति भावः ॥ यंचेति । लक्ष्यम् ॥ यतश्चेति । प्रदेशात् ॥ ततश्च लक्ष्यप्रदेशयोः कर्मापादानयोर्भेदान्मध्यव्यपदेशसद्भावः ॥

(उद्द्योतः) सप्तमीपञ्चम्यौ ॥ ७ ॥ प्रदेशादिति । स चेह इहेति सप्तम्या निर्दिष्ट इति यद्यपि तस्य स्थितिक्रियायामधिकरणत्वम्, तथापि वेधक्रियायामपादानत्वमित्यभिप्रेत्य भाष्ये यत इति पञ्चमीति बोध्यम् । क्रोशाल्लक्ष्यमित्यस्यैतः क्रोशादूर्ध्वं विद्यमानं लक्ष्यमित्यर्थः । तद्ध्वनयन्नाह—कर्मापादानयोरिति ॥

(तृतीयाक्षेपभाष्यम्)

तत्तर्हि वक्तव्यम् ? ॥

(समाधानभाष्यम्)

न वक्तव्यम् । नान्तरेण साधनं क्रियायाः प्रवृत्तिर्भवति । क्रियामध्यं चेत्कारकमध्यमपि भवति । तत्र 'कारकमध्ये' इत्येव सिद्धम् ॥ सप्तमीपञ्चम्यौ ॥ ७ ॥

(प्रदीपः) शक्तिः कारकमिति पक्षाश्रयेण वार्तिकं प्रत्याचष्टे—नान्तरेण साधनमिति । शक्तिमित्यर्थः । कालभेदभिन्नभुजिक्रियानुमितशक्तिभेदाश्रयो मध्यव्यपदेशोस्त्येवेत्यर्थः ॥ ७ ॥

(उद्द्योतः) भाष्ये साधनशब्देन तद्गता शक्तिरुच्यत इत्याह—शक्तिरिति ॥ शक्तेरतीन्द्रियत्वादाह—क्रियानुमितशक्तीति ॥ ७ ॥

(कर्मप्रवचनीययोगे विभक्तिनियमप्रकरणम्)

(३०० द्वितीयासूत्रम् ॥ २ । ३ । १ आ. ८ ॥

४६६ कर्मप्रवचनीययुक्ते द्वितीया ॥ २ । ३ । ८ ॥

(अर्थनियमाधिकरणम्)

(१४७६ अर्थनियमवार्तिकम् १)

॥ * ॥ कर्मप्रवचनीययुक्ते प्रत्यादिभिश्च लक्षणादिषूपसंख्यानं सप्तमीपञ्चम्योः प्रतिषेधार्थम् ॥ * ॥

(भाष्यम्) कर्मप्रवचनीययुक्ते प्रत्यादिभिश्च लक्षणादिषूपसंख्यानं कर्तव्यम् । वृक्षं प्रति विद्योतते विद्युत्, वृक्षं परि विद्योतते विद्युत, वृक्षमनु विद्योतते विद्युत् । साधुर्देवदत्तो मातरं प्रति । साधुर्देवदत्तो मातरं परि । साधुर्देवदत्तो मातरमनु ॥ किं प्रयोजनम् ? । सप्तमीपञ्चम्योः प्रतिषेधार्थम् । सप्तमीपञ्चम्यौ मा भूतामिति । "साधुनिपुणाभ्यामर्चायां सप्तमी" इति सप्तमी, "पञ्चम्यपाङ्परिभिः" इति पञ्चमी । तत्रायमप्यर्थः—अप्रतेरिति न वक्तव्यं भवति ॥

(प्रदीपः) कर्मप्रवचनीय ॥ ८ ॥ यदि सामान्येन कर्मप्रवचनीययुक्ते द्वितीयेति लक्षणं क्रियते, तदा 'वृक्षं परिविद्योतते' इत्यत्र विशेषविहितत्वात् पञ्चम्यपाङ्परिभिरिति पञ्चमी प्राप्नोति । साधुर्देवदत्तो मातरं प्रतीत्यत्र च साधुनिपुणाभ्यामिति परत्वात्सप्तमी प्राप्नोति तत्राप्रतेरिति वक्तव्यं भवतीति मत्वाह—प्रत्यादिभिश्च लक्षणादिष्विति । ततश्च पुनर्द्वितीयाविधानात् पूर्वोक्तदोषानवतारः ॥

(उद्द्योतः) कर्मप्र ॥ ८ ॥ पुनर्द्वितीयेति । वार्तिकेनेति शेषः ॥

(आक्षेपभाष्यम्)

तत्तर्हि वक्तव्यम् ? ॥

(समाधानभाष्यम्)

न वक्तव्यम् ॥ उक्तं वा ॥ । किमुक्तम् ? । एकत्र तावदुक्तम्—अप्रतेरिति ॥ इतरत्रापि—यद्यपि तावदयं परिदृष्टापचारो वर्जने चावर्जने च । अयं खल्वपशब्दोऽदृष्टापचारो वर्जनार्थ एव । तस्य कोन्यो द्वितीयः सहायो भवितुमर्हति—अन्यदतो वर्जनार्थात् । तद्यथा—अस्य गोर्द्वितीयेनार्थ इति गौरेवानीयते नाश्वो न गर्दभः ॥ कर्मप्रवचनीययुक्ते ॥ ८ ॥

(प्रदीपः) शिष्टं स्पष्टम् ॥ ८ ॥

(उद्द्योतः) भाष्ये—तावदुक्तमप्रतेरिति । तत्रत्यः प्रतिर्लक्षणेत्थमिति सूत्रस्थप्रतिपर्यनूनामुपलक्षणमित्यर्थः ॥ भाष्ये—वर्जनार्थ एवेति । तत्रैवार्थे तस्य कर्मप्रवचनीयत्वादिति भावः॥८॥

(३०१ कर्मप्रवचनीये सप्तमीसूत्रम् ॥ २ । ३ । १ आ. ९)

४६७ यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी ॥ २।३।९ ॥

(ईश्वरवचनशब्दार्थनिर्णयाधिकरणम्)

(आक्षेपभाष्यम्)

कथमिदं विज्ञायते—यस्य चैश्वर्यमीश्वरता ईश्वरभावस्तस्मात्कर्मप्रवचनीययुक्तादिति । आहो स्विद् यस्य स्वस्येश्वरस्तस्मात्कर्मप्रवचनीययुक्तादिति ? ।

(प्रदीपः) यस्माद् ॥ ९ ॥ इहाधि ब्रह्मदत्ते पञ्चाला अधि पञ्चालेषु ब्रह्मदत्त इति स्वस्वामिवाचिनोः पर्यायेण सप्तमीष्यते अन्यतरस्यैव तु प्राप्नोतीति विचारः क्रियते—कथमिति । तत्र यदान्तरेणापि भावप्रत्ययमीश्वरशब्देनैश्वर्यमुच्यते । अथ वेश्वर उच्यते अनेनेतीश्वरवचनमैश्वर्यमुच्यते तदा स्वामिनः सप्तमीत्ययमर्थो भवति । यदा यस्येत्यनेन स्वं निर्दिश्यते यस्य संबन्धीश्वर उच्यते तत्र सप्तमीत्युक्तं भवति ॥

(उद्द्योतः) यस्मादधिकम् ॥ ९ ॥ अन्यतरस्यैवेति । अधिरीश्वरे इति ईश्वरसंबन्धेऽधेः कर्मप्रवचनीयत्वविधानेन संबन्धस्य च स्वस्वामिनिष्ठत्वेनोभयोः कर्मप्रवचनीययुक्तत्वेपि यस्य चेश्वरवचनमित्यस्यावृत्तौ मानाभावेनान्यतरस्यैव प्राप्नोतीति भावः ॥ तात्पर्यग्राहकाभावाद् भावप्रधानत्वेऽपरितुष्यन्नाह—अथवेति । प्रवृत्तिनिमित्तेनैश्वर्येण हि ईश्वर उच्यते इति ईश्वरवचनशब्देनैश्वर्यमुच्यत इत्यर्थः । तत्रैश्वर्यं तदुपचारात्सप्तमी ॥ तत्रेति । तदेतिपाठ उचितः ॥

(भाष्यम्) कश्चात्र विशेषः ? ॥

(१४७७ प्रथमपक्षदूषणवार्तिकम् १)

॥ * ॥ यस्य चेश्वरवचनमिति कर्तृनिर्देशश्चेदवचनात्सिद्धम् ॥ * ॥

(भाष्यम्) यस्य चेश्वरवचनमिति कर्तृनिर्देशश्चेदन्तरेण वचनं सिद्धम् । अधि ब्रह्मदत्ते पञ्चालाः । आधृतास्ते तस्मिन् भवन्ति । सत्यमेवमेतत्—नित्यं परिग्रहीतव्यं परिग्रहीत्रधीनं भवति ॥

(प्रदीपः) कर्तृनिर्देशश्चेदिति । ईशितात्र कर्तृत्वेनाभिमतस्तेन स्वामिनः सप्तमीत्युक्तं भवति ॥ अवचनादिति । एतत्सूत्रारम्भेण विनापीत्यर्थः ॥ आधृता इति । स्वामिन्याधारे पञ्चालाः स्थिता इत्यर्थः । ततश्चाधिकरणलक्षणा सप्तमी सिद्धेत्यर्थः । सप्तमी शौण्डैरिति विकल्पेन समासविधानाद् अधि ब्रह्मदत्त इति ब्रह्मदत्ताधीना इति च भवति । विभक्त्यर्थवृत्तित्वे त्वधेरधिब्रह्मदत्तमिति च भवति ॥ सत्यमिति । अधिकरणं संमन्यते ॥

(उद्द्योतः) एतत्सूत्रेति । तदेकदेश—यस्य चेश्वरवचनमित्येतदित्यर्थः ॥ ब्रह्मदत्ताधीना इति । अषडक्षेत्यादिनाध्युत्तरपदत्वात्खः । अत एव परिग्रहीत्रधीनमिति वक्ष्यमाणभाष्यप्रयोगोपपत्तिः ॥ नन्वेवमधिनाव्ययीभावो न स्यादत आह—विभक्त्यर्थेति ॥ संमन्यत इति । तृतीय उक्तोर्थ उपपत्तियुक्त इत्यनुमोदत इत्यर्थः । अनुमोदनाकारमाह—भाष्ये—नित्यमित्यादि । परिग्रहीत्रधीनम् परिग्रहीत्राधारकमित्यर्थः ॥

(१४७८ द्वितीयदूषणवार्तिकम् ॥ २ ॥)

॥ * ॥ प्रथमानुपपत्तिस्तु ॥ * ॥

(भाष्यम्) प्रथमा नोपपद्यते ॥ कुतः ? । पञ्चालेभ्यः ॥

(प्रदीपः) प्रथमानुपपत्तिस्त्विति । सप्तमीविधानमनर्थकं प्रथमा च स्वाम प्राप्नोतीति दोषद्वयोपन्यासः ॥

(उद्द्योतः) प्रथमाचेति । भाष्ये तुशब्दश्चार्थे इति भावः ॥ सूत्रारम्भे तस्य वैयर्थ्यं प्रथमानुपपत्तिश्चेति दोषद्वयमिति तृतीयो वदतीति तात्पर्यम् ॥ एतत्सूत्रसत्त्वे हि अधिरीश्वरे इति कर्मप्रवचनीयसंज्ञाविधायकं कार्यम् । तथा चाधेः कर्मप्रवचनीयत्वात्तद्योगस्योक्तरीत्या स्ववाचकेपि सत्त्वाद् द्वितीया प्राप्नोतीति दोषः । एतत्सूत्राभावे तु ऐश्वर्यविषयेऽधेः क्रियायोगाभावेन गत्यादिसंज्ञाबाधरूपफलाभावाद् कर्मप्रवचनीयसंज्ञाया अप्यभावेन कर्मप्रवचनीययोगाभावाद् द्वितीयाऽप्राप्तौ प्रथमा सिध्यतीति भावः ॥

(आक्षेपभाष्यम्)

का तर्हि स्यात् ? ॥

(उद्द्योतः) भाष्ये का तर्हि स्यात्षष्ठीसप्तम्याविति शिरेकदेश्युक्तिः ॥

(समाधानभाष्यम्)

षष्ठीसप्तम्यौ "स्वामीश्वराधिपतिदायाद" इति ॥

(बाधकभाष्यम्)

न तत्राधिशब्दः पठ्यते ॥

(साधकभाष्यम्)

यद्यपि न पठ्यते । अधिरीश्वरवाची ॥

(प्रदीपः) अधिरीश्वरवाचीति । स्वामीश्वरेत्यर्थग्रहणात्पर्यायाणामपि ग्रहणं मन्यते ॥

(बाधकभाष्यम्)

न तत्र पर्यायवचनानां ग्रहणं भवति ॥ कथं ज्ञायते ? । यदयं कस्य चित्पर्यायवचनस्य ग्रहणं करोति—'अधिपतिदायाद' इति ।

(उद्द्योतः) अधिपतिदायाद इति । यस्य यो दायादः स तद्दानादिस्वामित्वात्स्वामीति लोके व्यवह्रियत इति ईश्वरपर्यायाविमाविति भावः ॥

(समाधानान्तरभाष्यम्)

षष्ठी तर्हि प्राप्नोति ।

(प्रदीपः) षष्ठी तर्हीति । स्वस्वामिसंबन्धसद्भावात् ।

(बाधकभाष्यम्)

शेषलक्षणा षष्ठी; अशेषत्वान्न भविष्यति ॥

(प्रदीपः) अशेषत्वादिति । प्रातिपदिकार्थमात्रनिष्ठत्वाद्व्यतिरेकाभावात् ॥

(उद्द्योतः) व्यतिरेकाभावादिति । भेदसंबन्धेनेतरान्वयित्वाभावादित्यर्थः ॥

(समाधानान्तरभाष्यम्)

द्वितीया तर्हि प्राप्नोति "कर्मप्रवचनीययुक्ते द्वितीया" इति ॥

(प्रदीपः) द्वितीया तर्हीति । अधिरीश्वर इत्यधेः कर्मप्रवचनीयत्वात् ॥

(उद्द्योतः) ननु ईश्वरत्वद्योतकस्येश्वरापेक्षया कर्मप्रवचनीयस्याधेः कथं पञ्चालसंबन्धद्योतकत्वं येन ततो द्वितीया स्यादत आह—अधिरीश्वर इत्यधेरिति । ऐश्वर्यविषयार्थद्योतकस्याधेरिति तदर्थ इति भावः । एवं च परस्परप्रतियोगिकसंबन्धस्य परस्परनिष्ठस्य तेन द्योतनादस्त्येव तत्प्राप्तिरिति भावः ॥

(बाधकभाष्यम्)

सप्तम्योक्तत्वात्तस्यार्थस्य द्वितीया न भविष्यति ॥

(प्रदीपः) सप्तम्येति । ब्रह्मदत्तशब्दादनेन द्वितीयापवादेन विधीयमानया सप्तम्योभयगतस्य संबन्धस्याभिधानात्पञ्चालशब्दाद् द्वितीया न भवतीत्यर्थः ॥

(उद्द्योतः) उभयगतस्य संबन्धस्येति । विशेषणादुत्पन्नया षष्ठ्यैवेति भावः ॥

(साधकभाष्यम्)

भवेद्योऽधेर्ब्रह्मदत्तस्य चाभिसंबन्धः स सप्तम्योक्तः स्यात् । यस्तु खल्वधेः पञ्चालानां चाभिसंबन्धस्तत्र द्वितीया प्राप्नोति ॥

(प्रदीपः) भवेदिति ॥ अधिरीश्वर इत्यत्रेश्वरेणेशितव्यस्याप्याक्षेपादीशितव्यस्याप्यधिना योगोऽस्तीति भावः ॥

(उद्द्योतः) भाष्ये—अधेर्ब्रह्मदत्तस्य चेति । अधिद्योत्यो ब्रह्मदत्तनिष्ठः संबन्ध इत्यर्थः ॥ एवमग्रेपि । चस्तूभयत्रापि वाक्यालंकारे ॥ ईशितव्यस्येति । ऐश्वर्यविषयाधेः कर्मप्रवचनीयत्वमिति तदर्थः । षष्ठी तु विशेषणादुत्पन्नाप्युभयगतं संबन्धं सामर्थ्याद्बोधयति ॥ परत्र तद्बोधकविभक्त्यविधानाद् । अत्र तु परत्रापि तद्बोधकविभक्तिप्राह्या विशेष्यनिष्ठसंबन्धबोधकत्वं न विशेषणविभक्तेरिति तात्पर्यम् । द्वितीया प्रथमापवादिकापीत्यभिमानः ॥

(१४७९ शेषपूर्तिवार्तिकम् ॥ ३ ॥)

॥ * ॥ स्ववचनात्तु सिद्धम् ॥ * ॥

(भाष्यम्) अस्तु—यस्य स्वस्येश्वरस्तस्मात्कर्मप्रवचनीययुक्तादिति ॥

(प्रदीपः) इदानीं द्वितीयं वाक्यं दर्शयितुमाह—स्ववचनादिति । यस्येश्वरवचनमित्यनेन स्वस्य सप्तमीप्रकृतित्वेन वचनात् प्रतिपादनात् ॥

(उद्द्योतः) सूत्रे स्वपदानुपादाने कथं स्ववचनात्प्राप्तिरत आह—यस्येति ॥

(स्वस्मिन्नपि सप्तमीविधानानर्थक्याक्षेपभाष्यम्)

एवमप्यन्तरेण वचनं सिद्धम् । अधि ब्रह्मदत्ते पञ्चालेषु—आधृतः स तेषु भवति । सत्यमेवमेतत्—नित्यं परिग्रहीता परिग्रहीतव्याधीनो भवति ॥

(द्वितीयदूषणभाष्यम्)

प्रथमानुपपत्तिस्तु ॥

प्रथमा तु नोपपद्यते ॥ कुतः ? । ब्रह्मदत्तात् ॥

(प्रत्याक्षेपभाष्यम्)

का तर्हि स्यात् ? ।

(समाधानभाष्यम्)

षष्ठीसप्तम्यौ—'स्वामीश्वराधिपतिदायाद—'इति ॥

(समाधानबाधकभाष्यम्)

न तत्राधिशब्दः पठ्यते ॥

(समाधानसाधकभाष्यम्)

यद्यपि न पठ्यते । अधिरीश्वरवाची ॥

(समाधानबाधकभाष्यम्)

न तत्र पर्यायवचनानां ग्रहणं भवति ॥ कथं ज्ञायते ? । यदयं कस्यचित्पर्यायवचनस्य ग्रहणं करोति—'अधिपतिदायाद—'इति ॥

(समाधानसाधकभाष्यम्)

षष्ठी तर्हि प्राप्नोति ॥

(समाधानबाधकभाष्यम्)

शेषलक्षणा षष्ठी, अशेषत्वान्न भविष्यति ॥

(समाधानसाधकभाष्यम्)

द्वितीया तर्हि प्राप्नोति 'कर्मप्रवचनीययुक्ते द्वितीया' इति ॥

(समाधानसाधकभाष्यम्)

सप्तम्योक्तत्वात्तस्याभिसंबन्धस्य द्वितीया न भविष्यति ॥

(प्रत्याक्षेपसमाधानसाधकभाष्यम्)

भवेद्योधेः पञ्चालानां चाभिसंबन्धः स सप्तम्योक्तः स्यात् । यस्तु खल्वधेर्ब्रह्मदत्तस्य चाभिसंबन्धः तत्र द्वितीया प्राप्नोति ॥

(उद्द्योतः) तत्र द्वितीया प्राप्नोतीत्यक्तं भाष्यं पूर्ववदेव व्याख्येयम् ॥

(व्याख्यानान्तरभाष्यम्)

एवं तर्हि—

स्ववचनात्तु सिद्धम्*इति ।

अधिः स्वं प्रति कर्मप्रवचनीयसंज्ञो भवतीति वक्तव्यम् ॥

(प्रदीपः) स्ववचनात्तु सिद्धमित्येतदन्यथा व्याख्यातुमाह—एवं तर्हीति । अधिरीश्वर इत्यत्रेश्वरग्रहणमपनीय 'आधिः स्वे' इति वक्तव्यम् । तत्र स्वमेव प्रत्यधिः कर्मप्रवचनीयसंज्ञः तस्मादेवानेन सप्तमी विधीयते । तेन स्वामिनं प्रत्यधेः कर्मप्रवचनीयत्वाभावात्ततो द्वितीयाया अभावः । तेनाधि पञ्चालेषु ब्रह्मदत्त इति सिद्धम् । अधि ब्रह्मदत्ते पञ्चाला इत्येतत्त्वधिकरणसप्तम्या सिद्धम् ॥

(उद्द्योतः) अत्र पक्षे द्वितीयावारणायाह—भाष्ये—एवंतर्हीति । स्ववचनादिति वार्तिकमेवैतद्दोषवारकमपीति व्याचष्ट इत्याह—अन्यथाव्याख्यातुमिति ॥

(आक्षेपभाष्यम्)

एवमपि यदा ब्रह्मदत्तेऽधिकरणे सप्तमी तदा पञ्चालेभ्यो द्वितीया प्राप्नोति [कथम्?।] "कर्मप्रवचनीययुक्ते द्वितीया" इति ॥

(समाधानभाष्यम्)

"उपपदविभक्तेः कारकविभक्तिर्बलीयसी" इति प्रथमा भविष्यति ॥ यस्मादधिकम् ॥ ९ ॥

(प्रदीपः) अत्र दोषमुद्भाव्य परिहरति—एवमपीत्यादिना भविष्यतीत्यन्तेन । तिष्ठन्ति सन्ति वेति स्थानादिक्रियापेक्षया पञ्चालानां कर्तृत्वात्कारकविभक्तिः प्रथमेति भावः । कर्मप्रवचनीयसंज्ञा त्वधि पञ्चालेषु ब्रह्मदत्त इत्यत्र चरितार्था । यथाधिकरणत्वं द्वयोरपि स्वस्वामिनोर्दर्शितं तथाधिरीश्वर इति यस्य चेश्वरवचनमिति च न कर्तव्यम् । ऐश्वर्यविषयस्य चाधेः क्रियायोगाभावाद् गत्युपसर्गसंज्ञाबाधनार्थोऽपि संज्ञाविधिर्नोपयुज्यते ॥ ९ ॥

(उद्द्योतः) भाष्ये—एवमपीति । अधेः स्वं प्रति कर्मप्रवचनीयत्वादिति भावः ॥ ननु संज्ञाविधानसामर्थ्याद् द्वितीया प्रथमां बाधेतेत्यत आह—कर्मप्रवचनीयसंज्ञा त्विति । तद्योगेऽपवादविधेस्तस्याः संज्ञाया द्वितीयाविधावनुपस्थानमित्यर्थः । उपपदविभक्तेरिति न्यायेनैव षष्ठीशेष इतिसूत्रे वक्ष्यमाणया पुरुषादिप्रधानपदात्षष्ठीवारकयुक्त्याप्यत्र द्वितीया वारयितुं शक्येति बोध्यम् ॥ यथाधिकरणत्वमिति । केचित्तु अधिकरणसप्तम्या संज्ञासूत्राभावेन द्वितीयायाः प्राप्त्यभावेन सूत्रप्रत्याख्याने तात्पर्ये सति स्वं प्रति कर्मप्रवचनीयत्वं नोपन्यस्येत् ॥ तस्मात्स्वस्वामिभावविवक्षायामाधारत्वाविवक्षायां सप्तम्यर्थं यस्य चेश्वरवचनमधिरीश्वर इति च सूत्रद्वयं कार्यम् । विनिगमनाविरहेण च सूत्रद्वयस्योभयत्रार्थे तात्पर्यमित्येव भाष्यतात्पर्यं लभ्यते न तु प्रत्याख्याने । अधिरीश्वरे इत्येतदीश्वरत्वे योत्ये ईश्वरे योत्य इति वा व्याख्येयम् । अन्त्ये स्वं प्रति कर्मप्रवचनीयत्वं लभ्यते । किंचाधिकरणसप्तम्यां पञ्चालेषु द्वितीयावारकयुक्त्येव पञ्चालेषु सप्तम्यां ब्रह्मदत्तादपि वारयितुं शक्यत्वेन स्ववचनात्तु सिद्धमित्यस्यायुक्तत्वे एव भाष्यतात्पर्यमित्याहुः ॥ ९ ॥

(३०२ द्वितीयाचतुर्थीसूत्रम् ॥२।३।१ आ. १०)

४७० गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ चेष्टायामनध्वनि ॥ २।३।१२ ॥

(अनुपपत्तिवारणाधिकरणम्)

(१४८० पर्यायग्राहकवार्तिकम् ॥ १ ॥)

॥ * ॥ अध्वन्यर्थग्रहणम् ॥ * ॥

(भाष्यम्) **अध्वन्यर्थग्रहणं कर्तव्यम् । इह मा भूत्—पन्थानं गच्छति, वीवधं गच्छतीति ॥**

(प्रदीपः) गत्यर्थ ॥ १२ ॥ स्वंरूपमिति वचनात् स्वरूपस्यैव ग्रहणं प्राप्तमित्याह—अध्वन्यर्थग्रहणमिति । तेनाध्वपर्यायेभ्योऽपि चतुर्थीप्रतिषेधो भविष्यति । द्वितीया तु कर्मणि द्वितीयेति भवति ॥

(उद्द्योतः) गत्यर्थ ॥ १२ ॥ तर्ह्यध्वादिभ्यो द्वितीयापि न स्यादत आह—द्वितीयेति । भाष्ये—वीवधमिति । 'पर्याहारश्च मार्गश्च विवधौ वीवधौ च तौ' इत्यमरः । 'पर्याहाराध्वमार्गेषु समौ विवधवीवधौ इति नानार्थकोशः ॥

(१४८१ नियमवार्तिकम् ॥२॥)

॥ * ॥ आस्थितप्रतिषेधश्च ॥ * ॥

(भाष्यम्) **आस्थितप्रतिषेधश्चायं वक्तव्यः । यो हुत्पथेन पन्थानं गच्छति, 'पथे गच्छति' इत्येव तत्र भवितव्यम् ॥**

(प्रदीपः) **आस्थितप्रतिषेध इति । आस्थित आ-**

क्रान्तः सन् यदा पन्था गम्यते तदाऽनध्वनीति प्रतिषेधः । यदा तूत्पथेन पन्था आक्रमितुमिष्यते तदा भवत्येव चतुर्थी ॥

(उद्योतः) भाष्ये—पथे गच्छतीत्येव तत्र भवितव्यमिति । एवकारो भिन्नक्रमः । इति तत्र भवितव्यमेवेत्यर्थः ॥

(सूत्रप्रयोजनाधिकरणम्)

(पूर्वपक्षिण आक्षेपभाष्यम्)

किमर्थं पुनरिदमुच्यते ? ।

(प्रदीपः) **किमर्थमिति ।** अन्तरेणाप्येतत्सूत्रं द्वितीयाचतुर्थ्योः सिद्धत्वादिति प्रश्नः ॥

(समाधानभाष्यम्)

चतुर्थी यथा स्यात् ॥

(आक्षेपभाष्यम्)

अथ द्वितीया सिद्धा ? ॥

(समाधानभाष्यम्)

सिद्धा 'कर्मणि' इत्येव ॥

(पूर्वपक्ष्याक्षेपसाधकभाष्यम्)

चतुर्थ्यपि सिद्धा ॥ कथम् ? । 'संप्रदाने' इत्येव ॥

(आक्षेपबाधकभाष्यम्)

न सिध्यति । "कर्मणायमभिप्रैति स संप्रदानम्" इत्युच्यते । क्रियया चासौ ग्राममभिप्रैति ॥ कया क्रियया ? । गमिक्रियया ॥

(पूर्वपक्ष्याक्षेपसाधकभाष्यम्)

क्रियाग्रहणमपि तत्र चोद्यते ॥

(प्रदीपः) **क्रियाग्रहणमपीति ।** यद्यपि तत्र क्रियाग्रहणं प्रत्याख्यातं तथापि तत्रैव न्यायस्योक्तत्वाद्वचनमाश्रित्यास्य सूत्रस्य प्रत्याख्यानं कृतम् ॥ अथवा तत्रत्यन्यायस्मरणार्थमिदमुक्तम् ॥ तत्र यदा गमनस्य संदर्शनादीनाञ्च भेदो विवक्ष्यते तदा संदर्शनादिभिः क्रियाभिराप्यमानत्वात् कर्मणा गमनेनाभिप्रेयमाणस्य संप्रदानत्वाच्चतुर्थी भवति । यदा त्वभेदविवक्षा तदा गमनस्य कर्मत्वाभावाद् ग्रामः कर्मैव भवतीति द्वितीया भवति । भेदाभेदविवक्षा च लौकिकप्रयोगानुसारेण नियतविषयेत्यारम्भप्रत्याख्यानयोर्नास्ति फलभेदः । अत एवापवादविषयेपि द्वितीयाविधानार्थं 'चतुर्थी वा' इति वक्तव्ये द्वितीयाग्रहणं प्रत्याख्यानेन भिन्नफलत्वादव्याख्यानीयम् ॥

(उद्योतः) **प्रत्याख्यातमिति ।** तथा चैतन्मात्रफलसाधकतद्वचनारम्भेणैतद्वचनप्रत्याख्यानं न चमत्कारकारीति भावः ॥ **न्यायस्येति ।** तत्फलस्यान्यथा साधनेन तद्वचनप्रत्याख्यानात्तत्पूर्वं तत्कर्तव्यं भवतीति भावः ॥ तदेव ध्वनयन्व्याख्यान्तरमाह— **अथवेति ।** न्यायमेव दर्शयति—**तत्रयदेति ॥ भेदइति ।** संयोगानुकूलव्यापाराद् यदा भेदो विवक्ष्यत इत्यर्थः । एतच्च कर्तरि कर्मेति सूत्रे संप्रदानसंज्ञासूत्रे च निरूपितं तत्र एवावधार्यम् । संयोगश्च कर्तृनिष्ठ एव फलत्वेन विवक्ष्यते यत्रापि सोप्यन्। अन्यथा परत्वात्कर्मत्वमेव स्यादित्याहुः ॥ **यदात्वभेदेति ।** ग्रामनिष्ठसंयोगानुकूलत्वेनैव यदा विवक्षेत्यर्थः ॥ **अत एवेति ।** चतुर्थी वेति वक्तव्ये द्वितीयाग्रहणमपवादकर्तृकर्मणोरितिषष्ठीविषये कृद्योगेपि द्वितीयार्थमिति न व्याख्यानीयं प्रत्याख्यानेन भिन्नफलत्वादित्यन्वयः ॥ अप्रत्याख्यानीयमिति पाठान्तरे तु चतुर्थी वेति वक्तव्ये द्वितीयाग्रहणमपवादविषयेपि द्वितीयाविधानार्थमिति न भवति । तस्य तथात्वे हि प्रत्याख्यानेन सह भिन्नफलत्वादिदं सूत्रमप्रत्याख्यानीयं स्यादिति योजना । एवं च भाष्यमते ग्रामस्य गन्तेत्यादौ षष्ठ्येवेति भावः ॥

(सूत्रारम्भे दोषवारणाधिकरणम्)

(१४८२ पूर्वपक्षवार्तिकम् ॥ ३ ॥)

॥ * ॥ चेष्टायामनध्वनि स्त्रियं गच्छत्यजां नयतीत्यतिप्रसङ्गः ॥ * ॥

(भाष्यम्) **चेष्टायामनध्वनीति 'स्त्रियं गच्छति' 'अजां नयति' इत्यतिप्रसङ्गो भवति ॥**

(प्रदीपः) इदानीं सूत्रस्यातिव्याप्त्युद्भावनायाह—**चेष्टायामिति ॥**

(१४८३ समाधानवार्तिकम् ॥ ४ ॥)

॥ * ॥ सिद्धं त्वसंप्राप्तवचनात् ॥ * ॥

(भाष्यम्) **सिद्धमेतत् ॥ कथम् ? । 'असंप्राप्ते कर्मणि द्वितीयाचतुर्थ्यौ भवत' इति वक्तव्यम् ॥**

(प्रदीपः) **सिद्धं त्विति ।** असंप्राप्तं यद्वस्तु गमनेन संप्रेप्स्यते तस्मिन् कर्मणीत्यर्थः । स्त्री तु संप्राप्तेति चतुर्थ्यभावः । अजां नयतीत्यत्राप्यजायाः संप्रापणाच्चतुर्थ्यभावः ॥ अथवा नयतिर्गत्यर्थ एव न भवति । प्रतीयते ह्यत्र गतिः नत्वसौ नयतेरर्थः । तस्य प्रापणवाचित्वादित्याहुः ॥

(उद्योतः) अथ वानयतिरिति । एतच्चगतीत्यत्र निरूपितम् ॥ १२ ॥

(१४८४ लाघवप्रदर्शकवार्तिकम् ॥५॥)

॥ * ॥ अध्वनश्चापवादः ॥ * ॥

(भाष्यम्) **एवं च कृत्वा अनध्वनीत्येतदपि न वक्तव्यं भवति । संप्राप्तं ह्येतत्कर्माध्वानं गच्छतीति ॥ गत्यर्थ० ॥ १२ ॥**

(प्रदीपः) **अध्वनश्चेति ।** यदा त्वसंप्राप्तोध्वा भवति तदा भवत्येव चतुर्थी अध्वने गच्छतीति प्रागेवोक्तम् ॥१२॥

(६०३ चतुर्थीसूत्रम् ॥२।३।१ आ. ११)

४७१ चतुर्थी संप्रदाने ॥२।३।१३॥

(न्यूनतापूर्त्यधिकरणम्)

(१४८५ न्यूनतापूरकवार्तिकम् ॥१॥)

॥ * ॥ चतुर्थीविधाने तादर्थ्ये उपसंख्यानम् ॥ * ॥

(भाष्यम्) चतुर्थीविधाने तादर्थ्ये उपसंख्यानं कर्तव्यम् । यूपाय दारु, कुण्डलाय हिरण्यमिति ॥

(प्रदीपः) चतुर्थी ॥१३॥ तादर्थ्य इति । तच्छब्देन कार्यं निर्दिश्यते । तस्मा इदं तदर्थमिति समासेन विशिष्टकार्यप्रयोजनं कारणमभिधीयते । तदर्थस्य भावस्तादर्थ्यमिति कार्यकारणसंबन्ध उच्यते **समासकृत्तद्धितेषु भावप्रत्ययेन संबन्धाभिधानमिति** वचनात् । तत्र द्विष्ठत्वेऽपि संबन्धस्य यथा षष्ठी विशेषणादेव भवति न विशेष्याद् राज्ञः पुरुष इति, तथा चतुर्थी— **यूपाय दार्विति** । **हेताविति** तृतीयाऽपि दारुशब्दान्न भवति।हेतुहेतुमद्भावस्य चतुर्थ्यैव गमितत्वात्प्रातिपदिकार्थव्यतिरेके च हेतुतृतीयाया विधानादिह च प्रातिपदिकार्थव्यतिरेकाभावात् ।

तस्मायित्युपकार्ये हि कार्ये प्रत्ययमृश्यते ।
तदर्थशब्दात्संबन्धे भावप्रत्यय इष्यते ॥
गम्यमानविभक्तित्वाच्चतुर्थी कार्यवाचिनि ।
गुणे कृतास्पदा तस्मात्कारणं नावगाहते ॥

(उद्द्योतः) चतुर्थी ॥ १३ ॥ तादर्थ्यशब्दार्थमाह—**तच्छब्देति** ॥ **कार्यप्रयोजनमिति** । बहुव्रीहिः । कार्यप्रयोजकमित्यर्थः । ब्राह्मणाय दधीत्यादौ दध्नो ब्राह्मणकारणत्वाभावादुक्तम्—**विशिष्टकार्येति** । भोजनविशिष्टो ब्राह्मणस्तत्रापि कार्यमिति भावः ॥ सोऽर्थो यस्येति बहुव्रीहिस्तु नोक्तः । तत्पुरुषस्यान्तरङ्गत्वात् ॥ **यथा षष्ठीति** । विशेषणनिष्ठतयैव सम्बन्धस्योद्भूततया प्रतीतेरिति भावः ॥ विभक्त्याभिधानेपि तिङादिभिरनभिधानाद्धेतौ तृतीया स्यादेवेत्यत आह—**प्रातिपदिकार्थव्यतिरेके चेति** । षष्ठीविषये हेतुतृतीयाविधानादिति भावः ॥ **प्रातिपदिकार्थेति** । हेतुत्वेनेतरान्वये च तृतीया भवति-एतदर्थस्य च क्वचिदर्थे तेनान्वयाभावादिति भावः ॥ उक्तमर्थं श्लोकाभ्यां संगृह्णाति—**तस्मायीति** । **उपकार्ये हीति** । विद्यमानमेव यत्किंचिदुपकारविशिष्टं कार्यमित्यर्थः । तेन घटाय दण्ड इत्यादि नेत्याहुः । मोक्षाय हरिं भजतीत्यादौ **क्रियया यमिति** संप्रदाने चतुर्थी बोध्या॥ **गम्यमानविभक्तित्वादिति** । **चतुर्थीतदर्थेति** सूत्रेण ज्ञाप्यमानविभक्तित्वादित्यर्थः । तद्धि ज्ञापकं कार्यवाचकाच्चतुर्थी सत्यामेव सङ्गच्छते इति भावः ॥

(आक्षेपभाष्यम्)

किमिदं तादर्थ्यमिति ? ॥

(प्रदीपः) **किमिदमिति** । तस्मा **इदमिति सत्यां** चतुर्थ्यां समासः । सति समासे तदनुवादेन **चतुर्थीविधान**मितीतरेतराश्रयत्वं मत्वा प्रश्नः ॥

(उद्द्योतः) तदनुवादेनेति । तदर्थानुवादेनेत्यर्थः ॥

(समाधानभाष्यम्)

तदर्थस्य भावः तादर्थ्यम् ॥

(आक्षेपभाष्यम्)

तदर्थं पुनः किम् ? ॥

(समाधानभाष्यम्)

सर्वनाम्नोयं चतुर्थ्यन्तस्यार्थशब्देन सह समासः ॥

(आक्षेपभाष्यम्)

कथं चात्र चतुर्थी ? ॥

(समाधानभाष्यम्)

अनेनैव ॥

(आक्षेपसाधकभाष्यम्)

यद्येवम्, इतरेतराश्रयं भवति ॥ केतरेतराश्रयता ? । निर्देशोत्तरकालं चतुर्थ्या भवितव्यम् । चतुर्थ्या च निर्देशः । तदेतदितरेतराश्रयं भवति । इतरेतराश्रयाणि च कार्याणि न प्रकल्पन्ते ॥

(तृतीयाक्षेपभाष्यम्)

तर्हि वक्तव्यम् ? ॥

(उद्द्योतः) नित्यशब्दत्वेनान्यत्रोक्तेनात्रापीतरेतराश्रयपरिहारः सुकरस्तथापि कार्यवादेपि परिहर्तुमाह—**तर्हीति** । चतुर्थीविधायकमन्यद् वचनमित्यर्थः ॥

(समाधानभाष्यम्)

न वक्तव्यम् । आचार्यप्रवृत्तिर्ज्ञापयति—'भवति ह्यर्थशब्देन योगे चतुर्थी' इति, यदयं "चतुर्थी तदर्थार्थ—" इति चतुर्थ्यन्तस्यार्थशब्देन सह समासं शास्ति ॥

न खल्वप्यवश्यं चतुर्थ्यन्तस्यैवार्थशब्देन समासो भवति ॥ किं तर्हि ? । षष्ठ्यन्तस्यापि भवति । तद्यथा—गुरोरिदं गुर्वर्थमिति ॥

(प्रदीपः) **षष्ठ्यन्तस्यापीति** । संबन्धसामान्यविवक्षायां षष्ठ्यस्त्येव ॥

(उद्द्योतः) वस्तुत इतरेतराश्रयत्वमेव नेत्याह—**न खल्वपीति** । यदि चतुर्थीसमासं विनान्यः समासो न स्यात् स्यादेवेतरेतराश्रयः । अस्ति चात्र षष्ठीसमास इत्याशयः ॥ नन्वत्र षष्ठी

कथमित्यत आह—सम्बन्धसामान्येति। तादर्थ्येन बोधे चतुर्थी सम्बन्धत्वेन बोधे षष्ठीति भावः॥ षष्ठीसमासोप्येतद्विषये शब्दशक्तिस्वभावान्नित्यसमास इत्याशयेनाह—भाष्ये-गुरोरिदमिति॥

(आक्षेपभाष्यम्)

यदि तादर्थ्ये उपसंख्यानं क्रियते नार्थः संप्रदानग्रहणेन। यो ह्युपाध्यायाय गौर्दीयते उपाध्यायार्थः स भवति। तत्र तादर्थ्य इत्येव सिद्धम्॥

(समाधानभाष्यम्)

अवश्यं संप्रदानग्रहणं कर्तव्यम्। याऽन्येन लक्षणेन संप्रदानसंज्ञा तदर्थम्—छात्राय रुचितं छात्राय स्वदितमिति॥

(उद्द्योतः) भाष्ये—यान्येनेति। रुच्यर्थानामित्यादिना॥ कर्मणायमभिप्रैतीति संज्ञाविधानं तु दाशगोघ्नौ संप्रदान इत्यर्थम्, तत्संप्रदानकं दानमिति बोधार्थं च। दानकर्मणो गवादेः संप्रदानार्थत्वेपि दानक्रियायास्तदर्थत्वाभावे चतुर्थ्यन्तार्थस्य दानक्रियान्वयानापत्तिरिति तदन्वयार्थं चेति दिक्॥

(आक्षेपभाष्यम्)

तत्तर्ह्युपसंख्यानं कर्तव्यम्?॥

(समाधानभाष्यम्)

न कर्तव्यम्। आचार्यप्रवृत्तिर्ज्ञापयति—'भवति तादर्थ्ये चतुर्थी' इति। यदयं "चतुर्थी तदर्थार्थ—" इति चतुर्थ्यन्तस्य तदर्थेन सह समासं शास्ति॥

(उद्द्योतः) भाष्ये—यदयमिति। यद्यपि समासः प्रकृतिविकृतिभाव एव तथापि तज्ज्ञाप्या चतुर्थी सर्वत्रेति भावः॥

(१४८६ चतुर्थीविधानवार्तिकम्॥ २॥)

॥ * ॥ क्लृपिसंपद्यमाने ॥ * ॥

(भाष्यम्) क्लृपिसंपद्यमाने चतुर्थी वक्तव्या। मूत्राय कल्पते यवागूः। उच्चाराय यवान्नमिति।

(प्रदीपः) क्लृपीति। संपत्तिरभूतप्रादुर्भाव उत्पत्तिरिह गृह्यत इति विकाराच्चतुर्थी। विकारस्य च प्रकृतिरूपारोपात्सामानाधिकरण्यं यत्र रूपमुपजायते ततश्चतुर्थीति प्रकृतेर्न भवति। यदा तु प्रकृतेरपादानविवक्षा तदा विकाराच्चतुर्थी न भवतीति केचिदाहुः। अन्ये तु विरोधाभावात्तत्रापि चतुर्थीमिच्छन्ति॥ १३॥

(उद्द्योतः) क्लृपि॥ सम्पत्तिशब्देन अभूतप्रादुर्भावरूपा उत्पत्तिरुच्यत इत्याह—सम्पत्तिरिति॥ नन्वेवं प्रकृतिविकृत्योर्भेदसत्त्वेनाभेदान्वयोनुभवसिद्धो भज्येतेत्यत आह—विकारस्येति। तथा च प्रकृतिवाचकसमानाधिकरणत्वात्प्राप्तप्रथमाविभक्तेरपवादोयमिति भावः। विरुद्धार्थकविभक्तिराहित्याच्च सामानाधिकरण्येनान्वय इति बोध्यम्॥ ननु सामानाधिकरण्ये प्रकृतेरपि चतुर्थी स्यादत आह—यत्र रूपमिति। अपादानविवक्षेति। अपादानपदेन शक्तिः। कल्पेरुत्पत्त्यर्थत्वे इदम्॥ अत्र वदन्ति—कल्पत इत्यादेः परिणमत इत्यर्थः। परिणामश्च रूपान्तरप्राप्तिः। तदेकदेशे रूपान्तरे मूत्रादेर्विकारस्याभेदेनान्वयेन ततो द्वितीयायां प्राप्तायां तद्बाधेन चरितार्था चतुर्थी अभेदविवक्षायां परत्वात् प्रथमया बाध्यते। यवागूर्मूत्रं कल्पत इत्येव हि तदा। ध्वनितं चेदं हरदत्तेन॥ कल्पेरुत्पत्त्यर्थत्वे जनिकर्तुरिति प्रकृतेः पञ्चम्यामपि विकृतिवाचकात्परत्वादुपपदविभक्तेरिति न्यायाच्च प्रथमैवेति दिक्॥ अन्येत्विति। त्रेयमेवारुचिः। प्रकृत्यादिभ्य इति तृतीयावत् प्रथमापवादोप्येत्यपरे॥ यद्यपि दारुयूपयोरिव यवागूमूत्रयोः प्रकृतिविकारभावोक्ति तथापि यवाग्वा मूत्रार्थत्वाभावान्न तादर्थ्यचतुर्थ्यास्य गतार्थता। एवमुत्पातेन ज्ञापिते इति वचनस्य सार्थक्यमूह्यम्॥

(१४८७ चतुर्थीविधानवार्तिकम्॥ ३॥)

॥ * ॥ उत्पातेन ज्ञाप्यमाने ॥ * ॥

(भाष्यम्) उत्पातेन ज्ञाप्यमाने चतुर्थी वक्तव्या। वाताय कपिला विद्युदातपायातिलोहिनी। [कृष्णा सर्वविनाशाय दुर्भिक्षाय सिता भवेत्॥] मांसौदनाय व्याहरति मृगः॥

(१४८८ चतुर्थीविधानवार्तिकम्॥ ४॥)

॥ * ॥ हितयोगे च ॥ * ॥

(भाष्यम्) हितयोगे चतुर्थी वक्तव्या। हितमरोचकिने हितमामयाविने॥ चतुर्थी सं०॥ १३॥

(उद्द्योतः) हितयोगे चेति। इदं तस्मै हितमिति निर्देशाज् ज्ञापकात्सिद्धमित्याहुः। अरोचके रोगाख्यायामिति ण्वुल् लोकतो नपुंसकत्वं ततो मत्वर्थ इनिः। सर्वत्रामयस्योपसंख्यानमित्यामयशब्दादिनिः। अन्यत्रापीति दीर्घः॥ १३॥

(३०४ उपपदचतुर्थीसूत्रम्॥२।३।१ आ० १२)

४७४ नमःस्वस्तिस्वाहास्वधालंवषड्योगाच्च ॥२।३।१६॥

(अनिष्टवारणाधिकरणम्)

(१४८९ विकल्पवारणवार्तिकम्॥ १॥)

॥ * ॥ स्वस्तियोगे चतुर्थी कुशलार्थैराशिषि वाविधानात् ॥ * ॥

(भाष्यम्) स्वस्तियोगे चतुर्थी कुशलार्थैराशिषि वाविधानाद् भवति विप्रतिषेधेन। स्वस्तियोगे

चतुर्थ्या अवकाशः—स्वस्ति जाल्माय स्वस्ति वृषलाय । कुशलार्थैराशिषि वाविधानस्यावकाशः—अन्ये कुशलार्थाः—कुशलं देवदत्तस्य कुशलं देवदत्ताय । इहोभयं प्राप्नोति—स्वस्ति गोभ्यः स्वस्ति ब्राह्मणेभ्य इति । चतुर्थी भवति विप्रतिषेधेन ॥

(प्रदीपः) नमःस्वस्ति ॥ १६ ॥ स्वस्तियोग इति । पूर्वविप्रतिषेधार्थं वचनम् ॥ स्वस्ति जाल्मायेति । तत्त्वकथनमिदं जाल्मत्वादाशीरभावः ॥

(उद्द्योतः) नमःस्वस्ति ॥ १६ ॥ पूर्वेति । पुनर्विधानार्थेन चेनेदं सिद्धमिति कश्चित् ॥

(१४९० नियमवार्तिकम् ॥ २ ॥)

॥ *॥ अलमिति पर्याप्त्यर्थग्रहणम् ॥ * ॥

(भाष्यम्) अलमिति पर्याप्त्यर्थग्रहणं कर्तव्यम् । इह माभूत्—अलं कुरुते कन्यामिति ॥

अपर आह—अलमिति पर्याप्त्यर्थग्रहणं कर्तव्यम् । इहापि यथा स्यात्—अलं मल्लो मल्लाय, प्रभुर्मल्लो मल्लाय, प्रभवति मल्लो मल्लायेति । नमःस्वस्ति० ॥ १६ ॥

(प्रदीपः) अलमिति । भूषणप्रतिषेधवाचिनोऽलंशब्दस्य निरासार्थं वचनम् । तेनालंकुरुते कन्याम्, अलं रोदनेनेति चतुर्थी न भवति ॥

नन्वत्रोपपदविभक्तेः कारकविभक्तिर्बलीयसीति चतुर्थी न भविष्यतीत्याह—अपर आहेति । सूत्रेऽलंशब्दमपनीय पर्याप्त्यर्थग्रहणं कर्तव्यम् । तेन तत्पर्यायाणामपि ग्रहणं सिध्यति । अन्यथा स्वरूपस्यैव ग्रहणं स्यात् । अथवाऽलमित्यर्थग्रहणं व्याख्येयमित्यर्थः ॥

(उद्द्योतः) अलं रोदनेनेति । रोदनं मा कुर्वित्यर्थः । एवं चात्र तृतीया कथं, तस्माद्रोदनेन साध्यं नास्ति अतस्तन्मा कुर्वित्यर्थः ॥ भाष्ये पर्याप्त्यर्थग्रहणमिति वार्तिकस्य द्वेधा व्याख्यानेन प्रभ्वादियोगे षष्ठ्यपीति ध्वनितम् ॥ १६ ॥

(२०५ कारकचतुर्थीसूत्रम् ॥२।३।१ आ० १२)

४७५ मन्यकर्मण्यनादरे विभाषा ऽप्राणिषु ॥२।३।१७॥

(इष्टोपपादनाधिकरणम्)

(आक्षेपभाष्यम्)

अप्राणिष्वित्युच्यते तत्रेदं न सिध्यति—'न त्वा श्वानं मन्ये, न त्वा शुने मन्ये' इति ॥

(समाधानभाष्यम्)

एवं तर्हि योगविभागः करिष्यते—"मन्यकर्मण्यनादरे विभाषा"। ततः "अप्राणिषु" अप्राणिषु च विभाषेति ।

(प्रदीपः) मन्यक० ॥ १७ ॥ एवं तर्हीति । योगविभागेन प्राणिविषया विभाषा क्रियते—न त्वा शुने मन्ये, न त्वां श्वानं मन्य इति । अप्राणिष्वित्यनेन त्वप्राणिविषया—न त्वा तृणाय मन्ये, न त्वा तृणं मन्य इति ॥

(आक्षेपभाष्यम्)

इहापि तर्हि प्राप्नोति—न त्वा काकं मन्ये, न त्वा शुकं मन्य इति ॥

(प्रदीपः) इहापीति । आद्येन योगेनेति भावः ॥

(उद्द्योतः) मन्यक० ॥ १७ ॥ भाष्ये—इहापीति । यद्यपि प्राण्यप्राणिषु उभयत्राप्याद्येनैव सिद्धे उत्तरयोगेनावस्थानित्यताज्ञापनात् क्वचिदेव प्रवृत्तिरिति न त्वां काकमित्यादौ नातिप्रसङ्गस्तथापि योगविभागं विनापि सर्वसमाधानं वक्तुमयमुपक्रमः ॥

(समाधानभाष्यम्)

यदेतद् 'अप्राणिषु' इति, एतद् 'अनावादिषु' इति वक्ष्यामि । इमे च नावादयो भविष्यन्ति । न त्वा नावं मन्ये यावत्तीर्णं न नाव्यम् । न त्वान्नं मन्ये यावद् भुक्तं न श्राद्धमिति । अत्र येषु प्राणिषु नेष्यते ते नावादयो भविष्यन्ति ॥

(प्रदीपः) तदेवं योगविभागेपि दोषदर्शनाद् न्यासान्तराश्रयणेनेष्टं साधयितुमाह—यदेतदिति ॥

(उद्द्योतः) अत्र भाष्ये येषु प्राणिषु नेष्यते इत्यत्र बहुवचनेन शुककाकातिरिक्तप्राणिन्यपि निषेधो ध्वनितस्तदभिप्रेत्यैव वृत्तौ शृगाल उदाहृतः ॥ भाष्ये—न त्वां नावं मन्ये यावत्तीर्णं न नाव्यमिति । यावद् यतो नाव्यं नावा स्वल्पनौकया तार्यमपि त्वया महत्यापि न तीर्णमतस्त्वां नावमुडुपमपि न मन्ये इत्यर्थः । नौशब्देनोडुपं स्वल्पनौकोच्यते । त्वांशब्दार्थस्तु महती नौः । एवं ह्यनादरो भवतीत्याहुः ॥ एवं नत्वान्नं मन्ये यावद्भुक्तं न श्राद्धमित्यस्य यतः श्राद्धं श्राद्धीयैर्विप्रैर्न भुक्तमतस्त्वामपूपरूपमन्नमोदनमपि न मन्ये इत्यर्थः ॥

(१४९१ वार्तिकम् ॥ १ ॥)

॥ * ॥ मन्यकर्मणि प्रकृष्य कुत्सितग्रहणम् ॥ * ॥

(व्याख्याभाष्यम्)

मन्यकर्मणि प्रकृष्य कुत्सितग्रहणं कर्तव्यम् । इह मा भूत्—त्वां तृणं मन्य इति ॥ मन्यकर्म॥१७॥

इति श्रीभगवत्पतञ्जलिविरचिते व्याकरणमहाभाष्ये द्वितीयस्याध्यायस्य तृतीये पादे प्रथममाह्निकम् ॥

(प्रदीपः) प्रकृष्य कुत्सितग्रहणमिति । यद्याचिन्चतुर्थी विधीयते ततः प्रकर्षेण यदि कुत्सा प्रतीयते तदा

चतुर्थी भवति न तु साम्यविवक्षायाम् । तेन प्रतिषेधयुक्तायां कुत्सायां चतुर्थीविधानं संपद्यते ॥ क्वचित् **प्रतिकृष्येति** पाठस्तत्राप्ययमर्थः । तृणादेरपि निकृष्टत्वं यदा प्रतिपिपादयिषितं **भवति** तदा चतुर्थी न तु साम्यविवक्षायाम् ॥ **प्रतिकृष्येति** । निकृष्येत्यर्थः । **मन्यकर्मण्यनादर उपमाने विभाषा-प्राणिष्वित्यापिशलिरधीते स्म** ॥ १७ ॥

इत्युपाध्यायजैयटपुत्रकैयटकृते भाष्यप्रदीपे द्वितीयस्याध्यायस्य तृतीये पादे प्रथममाह्निकम् ॥

(**उद्द्योतः**) **प्रकृष्य कुत्सितेति** । **परावरयोगे चेति** कृत्वा । अतिशयविशिष्टकुत्सितत्वे प्रतिपाद्ये इत्यर्थः । तदाह—**यद्वाधिक इति** । त्वां तृणमिव मन्य इत्यादावप्यनादरस्य सत्त्वाद् वार्तिकारम्भ इति भावः । **आपिशलिवाक्येनोपमानवाचकात्ततोपि** तिरस्कारे चतुर्थ्यनुच्यते ॥ १७ ॥

इति शिवभट्टसुतसतीगर्भजनागोजीभट्टविरचिते भाष्यप्रदीपोद्द्योते द्वितीयाध्यायस्य तृतीये पादे प्रथममाह्निकम् ॥

द्वितीयाध्यायस्य तृतीयपादे द्वितीयमाह्निकम् ॥

(तृतीयाप्रकरणम्)

(३०६ कारकतृतीयासूत्रम् ॥२।३।२ आ. १)

४७६ कर्तृकरणयोस्तृतीया ॥२।३।१८॥

(न्यूनतापूरणाधिकरणम्)

(१४९२ तृतीयाविधानवार्तिकम् ॥ १ ॥)

॥ * ॥ तृतीयाविधाने प्रकृत्यादिभ्य उपसंख्यानम् ॥ * ॥

(**भाष्यम्**) तृतीयाविधाने प्रकृत्यादिभ्य उपसंख्यानं कर्तव्यम् । प्रकृत्याभिरूपः । प्रकृत्या दर्शनीयः । प्रायेण याज्ञिकाः । प्रायेण वैयाकरणाः । माठरोऽस्मि गोत्रेण । गार्ग्योऽस्मि गोत्रेण । समेन धावति । विषमेण धावति । द्विद्रोणेन धान्यं क्रीणाति त्रिद्रोणेन धान्यं क्रीणाति । पञ्चकेन पशून् क्रीणाति । साहस्रेणाश्वान् क्रीणाति ॥

(**प्रदीपः**) **कर्तृकरणयोः** ॥ १८ ॥ **प्रकृत्याभिरूप इति** । क्रियापदाश्रवणात् कर्तृकरणयोरभावात् षष्ठ्यत्र प्राप्नोति ॥ **प्रायेणेति** । प्रायशब्दो बह्वर्थवाची । बहवो याज्ञिका इत्यर्थः । तत्र प्रथमा प्राप्नोति ॥ **गोत्रेणेति** । प्रथमा षष्ठी वात्र प्राप्नोति ॥ **समेनेति** । द्वितीया प्राप्नोति ॥ **द्विद्रोणेनेति** । द्वयोर्द्रोणयोः समाहारो द्विद्रोणम् । पात्रादित्वात् स्त्रीत्वाभावः । अत्रापि द्वितीया प्राप्नोति ॥ **पञ्चकेनेति** । पञ्च परिमाणमस्य पञ्चकः संघः । तत्र द्वितीया प्राप्ता । पशुभिस्त्वनेनैतत् समानाधिकरणम् । संघसंघिनोरभेदस्य विवक्षणात् ॥ **साहस्रेणेति** । सहस्रपरिमाणः संघः साहस्रः । **शतमानविंशतिकेत्यण्** । पूर्ववदत्र द्वितीयाप्राप्तिः ॥

(**उद्द्योतः**) **कर्तृकरणयोः** ॥ १८ ॥ **क्रियापदेति** । क्रियानध्याहारे विभक्त्यन्तरबाधनाय वार्तिकमिति भावः । अभिरूपादिकं तु गुणो न क्रियेति तात्पर्यम् ॥ **षष्ठ्यत्रेति** । प्रकृतिसम्बन्धी अभिरूप इति बोधादिति भावः ॥ **प्रथमाषष्ठी चेति** । गोत्राभिन्नगर्गापत्यमिति बोधे आद्या, सामान्यविशेषभावसम्बन्धेन गोत्रसम्बन्धिगार्ग्यत्ववानिति बोधेऽन्त्येति भावः ॥ **गोत्रशब्देनाग**स्त्याष्टमसप्तर्ष्यपत्यम् ॥ **अत्रापीति** । परिच्छेद्यपरिच्छेदकयोरभेदोपचारेण द्विद्रोणाभिन्नमित्यर्थात् ॥ **पञ्चके** 'संख्याया अतिशदन्ताया इति कन् ॥

(**आक्षेपभाष्यम्**)

तत्तर्हि वक्तव्यम्? ॥

(**वार्तिकप्रत्याख्यानभाष्यम्**)

न वक्तव्यम् । "कर्तृकरणयोस्तृतीया" इत्येव सिद्धम् ॥ इह तावत्—प्रकृत्याभिरूपः, प्रकृत्या दर्शनीय इति । प्रकृतिकृतं तस्याभिरूप्यम् ॥ प्रायेण याज्ञिकाः प्रायेण वैयाकरणा इति । एष तत्र प्रायः येन तेऽधीयते ॥ माठरोऽस्मि गोत्रेण गार्ग्योऽस्मि गोत्रेणेति । एतेनाहं संज्ञाये ॥ समेन धावति विषमेण धावतीति । इदमत्र प्रयोक्तव्यं सन्न प्रयुज्यते—समेन पथेति ॥ द्विद्रोणेन धान्यं क्रीणातीति । अत्रापि तादर्थ्यात्ताच्छब्द्यम् । द्विद्रोणार्थं द्विद्रोणम् द्विद्रोणेन हिरण्येन धान्यं क्रीणातीति ॥ पञ्चकेन पशून् क्रीणातीति । अत्रापि तादर्थ्यात्ताच्छब्द्यम्, पञ्चपश्वर्थः पञ्चकः । पञ्चकेन पशून् क्रीणातीति । साहस्रेणाश्वान् क्रीणातीति । सहस्रपरिमाणं साहस्रं साहस्रेण हिरण्येनाश्वान् क्रीणातीति ॥ कर्तृकरण० ॥ १८ ॥

(**प्रदीपः**) **प्रकृतिकृतमिति** । गम्यमानापि क्रिया करणादिव्यपदेशनिमित्तं भवति । यथा प्रविश पिण्डीमित्यत्र । इह च करणान्तरव्युदासाय प्रकृतेरेव करणत्वं विवक्षितम् । स्वभावेनायं कृतोभिरूपो न तु वस्त्रालंकरणादिनेत्यर्थः ॥ **एष तत्र प्राय इति** । बाहुल्यमित्यर्थः । तथाध्ययनस्य करणत्वेन विवक्षितम् ॥ **इदमत्रेति** । प्रतीयमानत्वाद् द्विद्रोणपञ्चकसाहस्रशब्दास्तत्क्रयार्थे मूल्ये उपचाराद्वर्तन्त इति करणत्वात् तृतीयासिद्धिः ॥ १८ ॥

(**उद्द्योतः**) **एष तत्र प्राय इति** । तत्रोदाहरणे एष प्रायः, पदार्थो येन हेतुना तेधीयत इत्यर्थः ॥ **तथाध्ययनस्येति** । अधीयत इति क्रियाध्याहार इति भावः । बहुभिरध्ययने ग्रहणधारणयोः सौकर्यं भवतीति बाहुल्यं तस्येन विवक्षितमिति बोध्यम् ॥ **एतेनाहं संज्ञाये इति** । अहं "माठरः" इति गोत्रेण रूपैः

संज्ञाये इत्यर्थः ॥ अप्रयोगे हेतुमाह—**प्रतीयेति**। अत्र केचित्—एवं रीत्या करणत्वादिव्युत्पादने हेताविति सूत्रस्येत्थंभूतलक्षण इत्यस्य च वैयर्थ्यापत्तिः । यदि तत्र द्रव्याद्यन्वयविवक्षायां सार्थक्यं तर्ह्यत्रापीति प्रत्याख्यानमत्रासिद्धान्त्येकदेश्युक्तिरेव । सम्बन्धसामान्यविवक्षायां षष्ठीबाधनार्थमावश्यकत्वाच्चेत्याहुः । अनभिधानेन भगवता प्रत्याख्यातमित्यन्ये ॥ १८ ॥

—>o<—

(३०७ उपपदतृतीयासूत्रम् ॥२।३।२ आ. २)

४७७ सहयुक्तेऽप्रधाने ॥२।३।१९॥

(सूत्रप्रयोजनाधिकरणम्)

(आक्षेपभाष्यम्)

किमुदाहरणम्? ॥

(प्रदीपः) **सहयुक्ते ॥ १९ ॥ किमुदाहरणमिति ।** सूत्रान्तरेण तृतीयासिद्धिं मत्वा पृच्छति ॥

(समाधानभाष्यम्)

तिलैः सह माषान्वपतीति ॥

(प्रदीपः) **तिलैः सहेति ।** अत्र माषा उप्यमानत्वात् प्रधानं कर्म । तिलास्तु तथायुक्ततया वृक्षमूलानीवोपसर्पणेऽप्रधानकर्माणीति द्वितीयायां प्राप्तायां तृतीयाविधिः ॥

(उद्द्योतः) **सहयुक्ते ॥ १९ ॥** ननु माषाणामिव तिलानामपि वापक्रिययेप्सितत्वादप्राधान्यमसिद्धमत आह—**तथायुक्ततयेति** । वस्तुतः सहार्थविशेषणत्वमप्राधान्यमिति न दोषः ॥

(समाधानबाधकभाष्यम्)

तिलैर्मिश्रीकृत्य माषा उप्यन्ते । तत्र "करणे" इत्येव सिद्धम् ॥

(प्रदीपः) **तिलैर्मिश्रीकृत्येति** । अन्तरङ्गत्वात् पूर्वं मिश्रणक्रियायां तिलाः करणत्वं प्रतिपद्यन्ते पश्चाद्वपनक्रियायां कर्मत्वमिति सिद्धा तृतीयेत्यर्थः ॥

(उद्द्योतः) ननु वापापेक्षया कर्मत्वेन मिश्रीकरणस्य च तदर्थत्वेनाप्राधान्यान्न्यायविरुद्धा तृतीयेत्याशङ्क्याह—**अन्तरङ्गत्वादिति** ॥ अन्तरङ्गत्वोपपादनमेव **पूर्वमित्यादि** । पूर्वं मिश्रणक्रियासम्बन्धे तदर्थत्वमपि न स्यादिति भावः ॥

(समाधानान्तरभाष्यम्)

इदं तर्हि—पुत्रेण सहागतो देवदत्त इति । अप्रधाने कर्तरि तृतीया यथा स्यात् ॥

(प्रदीपः) **पुत्रेण सहागत इति ।** पितुरेवात्रागमनक्रियायां शाब्दं कर्तृत्वं न तु पुत्रस्येत्यप्राप्ता तृतीया विधीयते॥

(उद्द्योतः) **ननु पुत्रस्येतीति** । तस्य सहार्थबलादनुमीयमानं कर्तृत्वमिति तृतीयाया अप्राप्तिरिति भावः ॥

(समाधानबाधकभाष्यम्)

एतदपि नास्ति प्रयोजनम् । प्रधाने कर्तरि लादयो भवन्तीति प्रधानकर्ता केनाभिधीयते । यश्चाप्रधानं सिद्धा तत्र 'कर्तरि' इत्येव तृतीया ॥

(प्रदीपः) **लादय इति** । आदिशब्देन कृदादीनां ग्रहणम् । तत्रैकेन शब्देन भिन्नकक्षत्वाद् गुणप्रधानयोः कर्त्रोरभिधानासंभवात् प्रधाने कार्यसंप्रत्ययात् प्रधानस्यैवाभिधानं न्याय्यमित्यप्रधानस्य प्रतीयमानगमिक्रियापेक्षकर्तृत्वाश्रयेण तृतीया सिद्धेत्यर्थः ॥

(उद्द्योतः) **एकेन शब्देन** । केन ॥ **गुणप्रधानयोरिति ।** प्रतीयमानोपात्तक्रियापेक्षत्वेन तादृशयोः कर्त्रोरित्यर्थः ॥ भाष्येऽप्रधाने इत्यस्य प्रतीयमानक्रियाकर्तरीत्यर्थः । **प्रधानकर्तरी**त्यस्योच्चारितशब्दबोध्यक्रियाकर्तरीत्यर्थः ॥ तदेवाह—**प्रतीयमानगमीति** । साहित्यानुपपत्त्यर्थः । प्रविश पिण्डीमित्यादौ प्रतीयमानक्रियापेक्षविभक्तेर्दृष्टत्वादिति भावः ॥ लादयस्तु न तथा धातोर्विधानादिति स्पष्टमेवेति ध्येयम् ॥ एकान्वयित्वादि—समानाधिकरणसाहित्यं हि पुत्रस्याध्याहृतागमनसम्बन्धज्ञान एव बोद्धुं शक्यं न त्वन्यथेति तात्पर्यम् ॥

(समाधानान्तरभाष्यम्)

इदं तर्हि—पुत्रेण सहागमनं देवदत्तस्येति ॥

(प्रदीपः) **पुत्रेण सहागमनमिति ।** ल्युटा कर्तुरनभिहितत्वाद् उभयत्र तृतीयाप्रसङ्गे नियमार्थमिदम्—अप्रधान एव तृतीया भवति न तु प्रधान इति ॥

(उद्द्योतः) षष्ठ्यत्र बाधिकेत्युत्तरदर्शनाद्देवदत्ते तृतीयार्थं सूत्रमिति भाति तदनिष्टमित्यत आह—**ल्युटेति** ॥

(समाधानबाधकभाष्यम्)

षष्ठ्यत्र बाधिका भविष्यति ॥

(प्रदीपः) **षष्ठ्यत्रेति । कर्तृकर्मणोः कृतीत्यनेन ।** सा च प्रधानयोरेव कर्तृकर्मणोः प्राधान्यादेव स्मर्यत इत्यप्रधाने कर्तरि न भविष्यति । यदा तु कृद्ग्रहणमप्रधानकर्तृप्रतिपत्त्यर्थं भेदिका देवदत्तस्य यज्ञदत्तस्य काष्ठानामिति तदा षष्ठीबाधनाय तृतीयाविधानमत्रापि भवत्येव ॥

(उद्द्योतः) भाष्ये—**षष्ठ्यत्रेति** । एवं चोभयोस्तृतीयाप्रसक्त्यभावेन नियमार्थत्वानुपपत्तिरिति भावः ॥ ननु षष्ठीबाधनार्थमेव तर्हीदमावश्यकमत आह—**सा च प्रधानेति** । प्रधाने चारितार्थ्यसम्भवादिति भावः ॥ **भवत्येवेति** ॥ अत्र वदन्ति—तृतीयाषष्ठ्योः को विशेषो यत् तृतीयाऽप्रधानेऽपि, षष्ठी नेति । एवं च पुत्रेण सहागमनमित्यादौ षष्ठीबाधनेन तृतीयार्थं सूत्रमावश्यकमिति ॥ अन्ये तु—कृद्योगे षष्ठी कृद्योगश्च तत्प्रकृत्यर्थान्वयमात्रेण । एवं च शाब्दकृत्प्रकृत्यर्थान्वयिनोः कर्तृकर्मणोरेव षष्ठी, न प्रतीयमानतत्संबन्धयोरिति भाष्योपपत्तिमाहुः ॥

(समाधानान्तरभाष्यम्)

इदं तर्हि—पुत्रेण सह स्थूलः । पुत्रेण सह पिङ्गल इति ।

(प्रदीपः) पुत्रेण सह स्थूल इति । गुणसंबन्धप्रतिपादनपरत्वादत्र क्रियाया अभावान् पुत्रस्य कर्तृत्वाभावः ॥

(उद्द्योतः) क्रियाया अभावादिति । अस्तिक्रियासत्त्वेपि साहित्यवत्तात्स्थौल्यमेव पुत्रे प्रतीयते न तु तत्क्रियाकर्तृत्वमिति भावः ॥

(पूर्वोक्तोदाहरणाभ्युपगमभाष्यम्)

इदं चाप्युदाहरणम्—तिलैः सह माषान्वपतीति ॥

(आक्षेपकारणभाष्यम्)

ननु चोक्तम्—तिलैर्मिश्रीकृत्य माषा उप्यन्ते तत्र करण इत्येव सिद्धम्—इति ॥

(समाधानभाष्यम्)

अथेत्सिद्धं यदा तिलैर्मिश्रीकृत्योप्येरन् । यदा तु खलु कस्य चिन्माषवीजावाप उपस्थितः तदर्थं च क्षेत्रमुपार्जितम् तत्रान्यदपि किंचिदुप्यते—यदि भविष्यति भविष्यतीति तदा न सिध्यति ॥

(प्रदीपः) यदि भविष्यतीति । अनेन मिश्रीकरणाभावात् तिलानां करणत्वाभावमाह । एकक्षेत्रे च वापात् सहयोगः कालभेदेप्यविरुद्धः ॥

(१४९३ सूत्रप्रत्याख्यानवार्तिकम् ॥ १ ॥)

॥ * ॥ सहयुक्तेऽप्रधानवचनमनर्थकमुपपदविभक्तेः कारकविभक्तिर्बलीयस्त्वादन्यत्रापि ॥ * ॥

(भाष्यम्) सह युक्तेऽप्रधानवचनमनर्थकम् ॥ किं कारणम् ? । उपपदविभक्तेः कारकविभक्तिर्बलीयस्त्वात् । अन्यत्रापि "उपपदविभक्तेः कारकविभक्तिर्बलीयसी" इति प्रथमा भवति । एवमत्रापि 'उपपदविभक्तेःकारकविभक्तिर्बलीयसी' इति प्रथमा भविष्यति ॥ कान्यत्र ? । गाः स्वामी व्रजतीति ॥ सह युक्ते ॥ १९ ॥

(प्रदीपः) सहयुक्त इति । अप्रधानवचनं प्रधाननिवृत्त्यर्थं क्रियते प्रधानस्य चान्तरङ्गत्वात् कारकविभक्तिर्भविष्यति इति नार्थस्तन्निवृत्त्यर्थेनाप्रधानवचनेनेत्यर्थः ॥ शिष्येण सहोपाध्यायस्य गौरित्यत्रापि गवा संबन्धोन्तरङ्ग इति उपाध्यायात् षष्ठ्येव भविष्यति न तृतीया ॥ गाः स्वामी व्रजतीति । अत्रापि व्रजिक्रियायां गवां कर्मत्वात्तन्निबन्धना द्वितीया स्वामीश्वरेति प्राप्तं उपपदविभक्तिं षष्ठीमपास्य बाधित्वा प्रवर्तते ॥

(उद्द्योतः) कारकविभक्तिरिति । निवृत्त्यादिक्रियानुपक्षास्थूल इत्यादावपि कर्तृत्वमस्तीति भावः । सहयोगश्च विशेष्यतया विशेषणतया वेति तात्पर्यम् ॥ अन्तरङ्गत्वादि॰.. । तदपवादत्ववारणायेदं वचनमेवेति चिन्त्यम् ॥ गवा सम्बन्धोन्तरङ्ग इति । एकान्वयित्वादिसमानाधिकरणाखण्डोपाधिरूपसाहित्यस्य सहशब्दार्थतया पूर्वमन्वयिज्ञानावश्यकत्वादिति भावः ॥ बाधित्वेति । स्वामित्वमपि गोनिरूपितमेवेति स्वामिशब्दयोगेपि गवामिति भावः ॥ १९ ॥

(३०८ तृतीयानियमसूत्रम् ॥ २।३।२ आ. ३)

४७८ येनाङ्गविकारः ॥ २।३।२० ॥

(अङ्गशब्दस्यावयविपरत्वनिर्णयाधिकरणम्)

(आक्षेपभाष्यम्)

इह कस्मान्न भवति—अक्षि काणमस्येति ? ॥

(प्रदीपः) येनाङ्गविकारः ॥ २० ॥ अङ्गशब्दोऽवयववाचित्वेन प्रसिद्धस्ततो येन गुणेनाङ्गस्य विकारो लक्ष्यते ततस्तृतीयेति सूत्रार्थमवगत्याह—इह कस्मादिति । इहैव कस्मान्नेत्यर्थः ॥ अक्षि काणमिति । कणनिमील इत्यस्य चौरादिकस्याचि घञि वा रूपम् । काणगुणयोगादभेदोपचाराद् गुणवचनेभ्यो लुगिति मतुपो लुग्विधानाद्वाऽक्षि काणशब्देनोच्यते । तत्र काणशब्दात् तृतीया प्राप्नोति । काणेन हि गुणेनाक्ष्णो विकारो लक्ष्यते । अक्ष्णा काण इत्यत्र लक्षिशब्दान्न प्राप्नोति ॥

(उद्द्योतः) येनाङ्ग ॥ २० ॥ अङ्गशब्दस्यार्शआद्यजन्तत्वे शङ्कानुपपत्तेराह—अङ्गशब्द इति । अप्रसिद्धत्वात्स न गृह्यत इति भावः ॥ अचि घञि वेति । उभावपि भाव इति भावः । एरजित्यच् ॥ नन्वेवं काणशब्देक्षिसामानाधिकरण्यमनुपपन्नमत आह—काणगुणेति ॥ लुग्विधानाद्वेति । इदं चिन्त्यम् । गुणगुण्युभयाभिधानसमर्थ एव तत्प्रवृत्तेः । नह्यक्ष्णः काणमिति कदाचिद्भवति । कर्मघनन्तः काणत्वगुणविशिष्टाक्षिवाचीति परे । न प्राप्नोतीति । शब्दतोङ्गविकाराप्रतीतेरिति भावः ॥

(१४९४ समाधानवार्तिकम् ॥ १ ॥)

॥ * ॥ अङ्गाद्विकृतात्तद्विकारश्चेदङ्गिनो वचनम् ॥ * ॥

(भाष्यम्) अङ्गाद्विकृतात्तृतीया वक्तव्या तेनैव चेद्विकारेणाङ्गी द्योत्यत इति वक्तव्यम् ॥

(प्रदीपः) अङ्गाद्विकृतादिति । अङ्गवाचिनोक्षिपदादेस्तृतीया भवति न काणादेर्गुणवचनादित्यर्थः ॥ एतावत्युच्यमानेऽक्षि काणमस्येत्यत्राप्यक्षिशब्दात्प्राप्नोतीत्याह—तद्विकारश्चेदिति । यदि देवदत्तादिरवयवी विकृतेनाङ्गेन विकारवान् प्रकाश्यत इत्यर्थः ॥

(आक्षेपभाष्यम्)

तर्हि वक्तव्यम् ? ॥

(समाधानभाष्यम्)

न वक्तव्यम् । अक्षशब्दोयं समुदायशब्दः । येनेति च करणे एषा तृतीया । येनावयवेन समुदायोऽङ्गी द्योत्यते तस्मिन् भवितव्यम् । न चैतेनावयवेन समुदायो द्योत्यते ॥ येनाङ्ग ॥ २० ॥

(प्रदीपः) **अङ्गशब्द इति** । अङ्गान्यस्य सन्तीत्यर्शआदित्वादच्प्रत्ययान्तोऽत्राङ्गशब्दो निर्दिष्टः । येनेत्यनेन विकृतमङ्गं निर्दिश्यते । न ह्यविकृतेनाङ्गेनाङ्गिनो विकारो द्योतयितुं शक्यते ॥ **न चैतेनेति** । अक्षि काणमस्येत्यत्र काणशब्देनाक्षिसमानाधिकरणेनावयवी नोच्यते, किं तर्ह्यवयव एवेत्यर्थः । अवयवश्चात्रावयविना विशेष्यत इति तस्यैव प्राधान्याद्विकारप्रतिपत्तिः ॥ २० ॥

(उद्द्योतः) **अच्प्रत्ययान्त इति** । अप्रसिद्धस्यापि व्याख्यानाद् ग्रहणमिति भावः ॥ **विकृतमङ्गमिति** । सामर्थ्यादिति भावः ॥ तदेवोपपादयति—**नहीति** ॥ **समुदायोङ्गी द्योत्यते** इति भाष्ये विकृत इत्यादिः ॥ **तस्यैव** । अवयवस्यैव ॥ **विकारप्रतिपत्तिरिति** । शाब्दीति भावः । आर्थी तत्प्रतीतिस्तु न तृतीयानिमित्तमिति ध्येयम् ॥ २० ॥

—∘∘:∘:∘∘—

(३०९ तृतीयानियमसूत्रम् ॥ २ । ३ । २ आ. ४)

४७९ इत्थंभूतलक्षणे ॥ २।३।२१ ॥

(समासान्तर्गतात्तृतीयावारणाधिकरणम् ।)

(१४९५ आक्षेपवार्तिकम् ॥ १ ॥)

॥*॥ इत्थंभूतलक्षणे तत्स्थे प्रतिषेधः ॥*॥

(भाष्यम्) **इत्थंभूतलक्षणे तत्स्थे प्रतिषेधो वक्तव्यः । अपि भवान्कमण्डलुपाणिं छात्रमद्राक्षीदिति ॥**

(प्रदीपः) **इत्थंभूत** ॥ २१ ॥ यदा लक्षणवाची शब्दो लक्ष्यवाचिसमासावयवस्तदा तृतीया मा भूदिति वचनम्—**इत्थंभूतलक्षणे तत्स्थ इति** । लक्ष्यवाचिशब्दस्थ इत्यर्थः ॥ **कमण्डलुपाणिमिति** । बहुव्रीहौ कृते कमण्डलुशब्दात् तृतीया प्राप्नोति । न च प्रत्ययलक्षणेनाप्रत्यय इति प्रातिपदिकसंज्ञानिषेधो **नङिसंबुद्ध्योरिति** नलोपप्रतिषेधाज् ज्ञापकात् । न च तृतीयाया लुक् प्राप्नोति । समासप्रातिपदिकानवयवत्वात्तस्याः कृते समास उत्पादनात् ॥

(उद्द्योतः) **इत्थं भूत** ॥ २१ ॥ भाष्ये—**इत्थं भूतलक्षणे इति** । इत्थंभूतस्य लक्षणबोधके शब्दे तत्स्थे लक्ष्यवाचिपदघटितपदस्थे सति लक्षणवाचकात्तृतीयाप्रतिषेधो वक्तव्य इत्यर्थः ॥ तदाह—**यदा लक्षणवाचीति** ॥ लक्ष्यवाचिनः शब्दस्य लक्षणवाचिनः समासं विना लक्षणवाचिनस्तत्स्थत्वं न सम्भवतीत्यत आह—**लक्ष्यवाचिसमासेति** । लक्ष्यवाचिघटकसमासेत्यर्थः ॥ कमण्डलुपाणिशब्दो बहुव्रीहिणा लक्ष्यच्छात्रवाची तत्र पाणिशब्दस्य लक्षणत्वायोगात्पारिशेष्यादाह—**कमण्डलुशब्दादिति** । इत्थंभूतश्छात्रस्तं प्राप्तश्छात्रस्तस्य लक्षणं कमण्डलुरिति भावः । बहुव्रीहौ समुदायस्य संबन्धित्वेन संबन्धी बोध्यः, तत्र चेतरपदार्थान्वय इति व्यपेक्षावादे शङ्क्यम् तत्र हि तृतीयायामपि कमण्डलोर्प्राप्यत्वेनान्वयः सुवचः ॥ पाण्यधिकरणकमण्डलुप्राप्यश्छात्र इत्यर्थः स्यादिति भावः ॥ **ज्ञापकादिति** । एतेन नलोपविषयमेव तज्ज्ञापकमित्यपास्तम् । **तत्स्थे इत्थंभूतलक्षण इति** वार्तिकस्वारस्येनावयवात्तृतीयापत्तेः प्रतीयमानत्वात् । एतेन समुदायात्तृतीयापत्तौ तात्पर्यमिति मन्दोक्तमपास्तम् ॥ **प्रातिपदिकानवयवत्वादिति** । तन्मध्यपतितन्यायादकज्वत्तद्ग्रहणेन ग्रहणेपि कुम्भादिवच्छात्रेणावयवत्वाबोधनादवयवत्वे मानाभावादिति भावः । पूर्वं लक्षणत्वाविवक्षया प्रथमान्तत्वेन समासे जाते पश्चाल्लक्षणत्वविवक्षायामत्र तृतीयापादनं कृतपूर्वी कटमिति वदिति बोध्यम् ॥ केचित्तु कमण्डलुपाणिशब्दादत्र तृतीयापत्तिः । कमण्डलुपाणित्वस्यैव लक्षणत्वात्सकृदसौ **कमण्डलुपाणिश्छात्रोऽदृष्टस्तस्य तदेव लक्षणं भवतीति अनुर्लक्षण इति सूत्रे** भाष्यात् । तदेवेत्यस्य कमण्डलुपाणित्वमेवेत्यर्थः । अन्यथा स एवेति वदेत् । कमण्डलुयुक्तपाणिश्छात्रस्तदवयवीति बोधः स्यात् । कमण्डलुयुक्तार्थकमण्डलुपदेन समानाधिकरणो बहुव्रीहिः । अन्यथा तन्मध्यपतितन्यायेन तद्ग्रहणेऽपि तदवयवत्वं नेत्यस्यापातरमणीयत्वेन लुग् दुर्वार एव । अत एवेच एकाचोमिति सूत्रे भाष्ये—नरंमन्य इत्यादौ समासप्रातिपदिकसंज्ञोत्तरं जातस्याप्यमः सुपोधातुरिति लुगम् विधिसामर्थ्यान्नेत्युक्तमित्याहुः ॥

(१४९६ समाधानवार्तिकम् ॥ २ ॥)

॥ * ॥ न वेत्थंभूतस्य लक्षणेनापृथग्भावात् ॥ * ॥

(भाष्यम्) **न वा वक्तव्यम्? । किं कारणम् । इत्थंभूतस्य लक्षणेनापृथग्भावात् । यत्रेत्थंभूतस्य पृथग्भूतं लक्षणं तत्र भवितव्यम् । न चात्रेत्थंभूतस्य पृथग्भूतं लक्षणम् ॥**

(प्रदीपः) **लक्षणेनेति । पृथग्विनेति तृतीया ॥**

(उद्द्योतः) भाष्ये—[अ]**पृथग्भावादिति** । एकार्थीभावे इतरविशेषणस्यैव कमण्डलोरुपस्थित्या तस्य लक्षणत्वेन छात्रेन्वयासंभव इति भावः ॥ तदेतद्वक्ष्यति कैयटः—**नास्ति लक्षणस्य भावान्यमिति** । विशेषणत्वानाक्रान्तोपस्थितिरित्यर्थः ॥

(आक्षेपभाष्यम्)

किं वक्तव्यमेतत् ? ॥

(उद्द्योतः) प्रागुक्ताशयानभिज्ञः शङ्कते—**किं वक्तव्यमिति॥**

(समाधानभाष्यम्)

नहि ॥ कथमनुच्यमानं गंस्यते ? । तथा ह्ययं

प्राधान्येन लक्षणं प्रतिनिर्दिशति—इत्थंभूतस्य लक्षणमित्थंभूतलक्षणं तस्मिन्नित्थंभूतलक्षण इति ॥ इत्थंभूत० ॥ २१ ॥

(प्रदीपः) तथा ह्ययमिति । षष्ठीतत्पुरुषस्योत्तरपदार्थप्रधानत्वात् । इत्थंभूतस्य यल्लक्षणं प्रधानमप्राप्तोपसर्जनभावं तत्र तृतीया यथा कमण्डलुना छात्रमद्राक्षीदिति । बहुव्रीहौ तु स्वार्थोपसर्जनान्यपदार्थाभिधायित्वाद्वृत्तिपदानां नास्ति लक्षणस्य प्राधान्यम् ॥ २१ ॥

(उद्द्योतः) अत्रार्थे सूत्रारूढामभ्युच्चययुक्तिमप्याहैकदेशी भाष्ये—प्राधान्येनेति ॥ २१ ॥

(३१० तृतीयासूत्रम् ॥ २ । ३ । २ आ. ५)

४८० संज्ञोन्यतरस्यां कर्मणि ॥२।३।२२॥

(विप्रतिषेधाधिकरणम्)

(१४९७ वार्तिकम् ॥ १ ॥)

॥ * ॥ संज्ञः कृत्प्रयोगे षष्ठी विप्रतिषेधेन ॥ * ॥

(भाष्यम्) "संज्ञोन्यतरस्यां कर्मणि" इत्येतस्मात्कृद्योगे षष्ठी भवति विप्रतिषेधेन । "संज्ञोन्यतरस्याम्" इत्यस्यावकाशः—मातरं संजानीते मात्रा संजानीते । कृत्प्रयोगे षष्ठ्या अवकाशः—इध्मप्रव्रश्चनः पलाशशातनः । इहोभयं प्राप्नोति—मातुः संज्ञाता पितुः संज्ञाता इति । षष्ठी भवति विप्रतिषेधेन ॥

(प्रदीपः) संज्ञोऽन्यतरस्याम् ॥ २२ ॥ मात्रा संजानीत इति । संप्रतिभ्यामनाध्यान इत्यात्मनेपदम् ॥

(१४९८ वार्तिकम् ॥ २ ॥)

॥*॥ उपपदविभक्तेश्चोपपदविभक्तिः॥*॥

(भाष्यम्) उपपदविभक्तेश्चोपपदविभक्तिर्भवति विप्रतिषेधेन । 'अन्यारादितरर्तेदिक्शब्दाञ्चूत्तरपदाजाहियुक्ते' इत्यस्यावकाशः—अन्यो देवदत्तात् । 'स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च' इत्यस्यावकाशः—गोषु स्वामी गवां स्वामी । इहोभयं प्राप्नोति—अन्यो गोषु स्वामी अन्यो गवां स्वामी । 'स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च' इत्येतद्भवति विप्रतिषेधेन ॥

(प्रदीपः) अन्यो गवां स्वामीति । एकस्मिन्वाक्ये सहप्रयोगादस्त्यन्ययोगो गवामिति मन्यते ॥

(बाधकभाष्यम्)

नैष युक्तो विप्रतिषेधः । नह्यत्र गावोऽन्ययुक्ताः ॥ कस्तर्हि ? । स्वामी ॥

(प्रदीपः) न ह्यत्र गाव इति । युक्तग्रहणाद्यदपेक्षमन्यत्वं तद्वाचिनः पञ्चमी । नचात्र गवापेक्षमन्यत्वं स्वामिनः प्रतिपाद्यं व्यभिचाराभावात् किं तर्हि ? पूर्वस्वाम्यपेक्षम् ॥ कस्तर्हि स्वामीति । भूतपूर्वो यः स्वामी सोन्ययुक्त इत्यर्थः ॥

(उद्द्योतः) संज्ञोन्यत ॥ २२ ॥ अन्यपदार्थेन योगे स्वामिनः पञ्चमी स्यादत आह—भूतपूर्वेति ॥ अन्ययुक्त इति । अन्यत्वप्रतियोगीत्यर्थः । पूर्वस्वाम्यपेक्षयेदानीमन्यो गवां स्वामीत्युदाहरणार्थः ॥

(वार्तिकोदाहरणान्तरभाष्यम्)

एवं तर्हि "तुल्यार्थैरतुलोपमाभ्यां तृतीयान्यतरस्याम्" इत्यस्यावकाशः—तुल्यो देवदत्तस्य । तुल्यो देवदत्तेन । "स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च" इत्यस्यावकाशः—स एव । इहोभयं प्राप्नोति—तुल्यो गोभिः स्वामी तुल्यो गवां स्वामी । "तुल्यार्थैरतुलोपमाभ्यां तृतीयान्यतरस्याम्" इत्येतद्भवति विप्रतिषेधेन ॥ संज्ञोन्य ॥ २२ ॥

(प्रदीपः) तुल्यो गोभिः स्वामीति । गवां यः स्वामी स गोभिर्जात्यादिना धर्मेण सदृश इत्यर्थविवक्षायामस्ति गवा पदद्वयार्थयोगः ॥ २२ ॥

(उद्द्योतः) उभयप्राप्तये गवा तुल्येन च स्वामिनः संबन्धमुपपादयति—गवां य इति ॥ २२ ॥

(३११ उपपदतृतीयासूत्रम् ॥ २ । ३ । २ आ. ६)

४८१ हेतौ ॥ २।३।२३ ॥

(१४९९ वार्तिकम् ॥ १ ॥)

॥ * ॥ निमित्तकारणहेतुषु सर्वासां प्रायदर्शनम् ॥ * ॥

(भाष्यम्) निमित्तकारणहेतुषु सर्वाः प्रायेण दृश्यन्त इति वक्तव्यम् । किं निमित्तं वसति । केन निमित्तेन वसति । कस्मै निमित्ताय वसति । कस्मान्निमित्ताद्वसति । कस्य निमित्तस्य वसति । कस्मिन्निमित्ते वसति । किं कारणं वसति । केन कारणेन वसति । कस्मै कारणाय वसति । कस्मात्कारणाद्वसति । कस्य कारणस्य वसति । कस्मिन्कारणे वसति । को हेतुर्वसति । कं हेतुं वसति । केन हेतुना वसति । कस्मै हेतवे वसति । कस्माद्धेतोर्वसति । कस्य हेतोर्वसति । कस्मिन्हेतौ वसति ॥ हेतौ ॥ २३ ॥

(प्रदीपः) हेतौ ॥ २३ ॥ योग्यतामात्रयुक्तोऽनाश्रितव्यापारोर्थो द्रव्यगुणक्रियाविषयो हेतुः ॥ निमित्तेति । असर्वनाम्नोपि विधानार्थमत्र सूत्र इदं पठितं न तु सर्वनाम्नः स्तृतीया चेत्यत्र । तत्र प्रायग्रहणादसर्वनाम्नः प्रथमाद्वि-

तीये न भवतोन्यास्तु यथादर्शनं भवन्ति। पर्यायोपादानं केचित्पर्यायान्तरनिवृत्त्यर्थमिच्छन्ति। अन्ये तूपलक्षणार्थमिच्छन्तः प्रयोजनादिप्रयोगेप्येतद्विभक्तिविधानं मन्यन्ते॥

(उद्द्योतः) हेतौ॥ २३॥ व्यापारानाविष्टत्वे द्रव्यगुणक्रियाविषयत्वे च हेतुर्योग्यतामात्रयुक्त इति। व्यापाराविष्टं क्रियामात्रविषयं च करणं. व्यापारावेशे च क्रियाविषयत्वमेव फलोपधानमेवेति ततो भेद इति भावः॥ न स्विति। पृच्छिकारवदिति भावः। अन्येस्त्विति मतेनुप्रादकाभावोरुचिबीजम्॥ २३॥

(३१२ कारकपञ्चमीसूत्रम्॥ २। ३। २ आ. ७॥)

४८६ अपादाने पञ्चमी॥ २।३।२८॥

(न्यूनतावारणाधिकरणम्)

(१५०० वार्तिकम्॥ १॥)

॥ * ॥ पञ्चमीविधाने ल्यब्लोपे कर्मण्युपसंख्यानम्॥ * ॥

(भाष्यम्) पञ्चमीविधाने ल्यब्लोपे कर्मणि पञ्चम्या उपसंख्यानं कर्तव्यम्। प्रासादमारुह्य प्रेक्षते—प्रासादात्प्रेक्षते॥

(प्रदीपः) अपादाने॥२७॥ ल्यब्लोप इति। यत्र ल्यबन्तस्याप्रयोगेऽप्यर्थो गम्यते तत्र द्वितीयायां प्राप्तायां पञ्चमी विधीयते॥

(उद्द्योतः) अपादाने॥२७॥ ननु ल्यब्लोपविधायकस्यात्र शास्त्रेऽदर्शनाल्ल्यब्लोप इत्यसंगतमत आह—यत्रेति। वाक्यैकदेशन्यायेनेति भावः॥ ल्यब्ग्रहणं क्त्व उपलक्षणम्। आसनात्प्रेक्षत इत्यस्यासने स्थित्वेत्यर्थः॥ तत्रेति। ल्यबन्ताभावेपि गम्यमानक्रियापेक्षकर्मत्वादिति भावः॥

(१५०१ वार्तिकम्॥ २॥)

॥ * ॥ अधिकरणे च॥ * ॥

(भाष्यम्) अधिकरणे चोपसंख्यानं कर्तव्यम्। आसनात्प्रेक्षते। शयनात्प्रेक्षते॥

(प्रदीपः) अधिकरणे चेति। ल्यब्लोप इत्यपेक्षते। सप्तम्यपवादोत्र पञ्चमी॥

(१५०२ वार्तिकम्॥ ३॥)

॥ * ॥ प्रश्नाख्यानयोश्च॥ * ॥

(भाष्यम्) प्रश्नाख्यानयोश्च पञ्चमी वक्तव्या। कुतो भवान्?। पाटलिपुत्रात्॥

(प्रदीपः) प्रश्नाख्यानयोश्चेति। विशिष्टे प्रश्नाख्याने गृह्येते—यत्र लोके पञ्चमी प्रयुज्यते। तेन कस्यायमश्वो देवदत्तस्यायमश्व इत्यादौ पञ्चमी न भवति॥ कुतो भवानिति। क्रियाया अभावादनपादानत्वं मन्यते॥

(उद्द्योतः) गम्यमानक्रियापेक्षयाऽपादानत्वं भविष्यतीत्यत आह—क्रियाया इति॥

(१५०३ वार्तिकम्॥ ४॥)

॥ * ॥ यतश्चाध्वकालनिर्माणम्॥ * ॥

(भाष्यम्) यतश्चाध्वकालनिर्माणं ततः पञ्चमी वक्तव्या। गवीधुमतः सांकाश्यं चत्वारि योजनानि॥ कार्तिक्या आग्रहायणी मासे॥

(प्रदीपः) यतश्चेति। यदाश्रित्याध्वकालौ परिच्छिद्येते तत्र पञ्चमीत्यर्थः॥ गवीधुमत इति। गवीधुमन्नाम नगरम्॥

(उद्द्योतः) यदाश्रित्येति। यदवधित्वेनाश्रित्येत्यर्थः॥ तत्रेति। तत्र वर्तमानाच्छब्दादित्यर्थः॥

(१५०४ वार्तिकम्॥ ५॥)

॥ * ॥ तद्युक्तात्काले सप्तमी॥ * ॥

(भाष्यम्) तद्युक्तात्काले सप्तमी वक्तव्या। कार्तिक्या आग्रहायणी मासे॥

(प्रदीपः) तद्युक्तात्कालइति। काले विषये। तेन पञ्चम्यन्तार्थेन यो युक्तो मासादिस्तद्वाचिनः सप्तमीत्यर्थः। अथ वा पञ्चमीयुक्तार्थात्परे काल इत्यर्थः॥

(उद्द्योतः) तद्युक्तात्कालादित्युचितमत आह—कालेविषये इति॥ युक्तोमासादिरिति। मासकार्तिक्योश्चावध्यवधिमद्भावः संबन्धः। आग्रहायण्यास्तु न तद्युक्तत्वमिति भावः॥ अथवापञ्चमीति। तच्छब्देन पञ्चमी परामृश्यते तद्युक्तश्च तत्प्रकृत्यर्थस्तस्मात्परे परावयवके कालेभिधेये कालवाचिनः सप्तमीत्यर्थः। आग्रहायण्याश्चार्थ परत्वं न शाब्दं तत्तु मासस्यैवेति भावः॥

(१५०५ वार्तिकम्॥ ६॥)

॥ * ॥ अध्वनः प्रथमा च॥ * ॥

(भाष्यम्) अध्वनः प्रथमा च सप्तमी च वक्तव्या। गवीधुमतः सांकाश्यं चत्वारि योजनानि। गवीधुमतः सांकाश्यं चतुर्षु योजनेषु॥

(प्रदीपः) अध्वन इति। तद्युक्तादित्यपेक्षते॥

(आक्षेपभाष्यम्)

तत्तर्हीदं बहु वक्तव्यम्?॥

(प्रथमद्वितीयवार्तिकप्रत्याख्यानभाष्यम्)

(भाष्यम्) न वक्तव्यम्। "अपादाने" इत्येव सिद्धम्। इह तावत्प्रासादात्प्रेक्षते शयनात्प्रेक्षते इति, अपक्रामति तत्तस्माद्दर्शनम्॥ यद्यपक्रामति किं नात्यन्तायापक्रामति?। संततत्वात्॥ अथ वान्यान्यप्रादुर्भावात्। अन्या चान्या च प्रादुर्भवति॥

(प्रदीपः) अपक्रामति तत्तस्मादिति। दर्शनं चक्षुरिन्द्रियं तेजोरूपं प्राप्य विषयग्राहित्वात्प्रासाददेशादपक्रम्य

विषयं गच्छतीत्यर्थः ॥ क्षणिकपक्षावष्टम्भेन भेदमाश्रित्याह— **अथ वान्यान्यप्रादुर्भावादिति** । अन्यस्यान्यस्य तेजोरूपस्येन्द्रियस्योत्पादादित्यर्थः । भाष्यकारवचनप्रामाण्यादन्यान्यशब्दस्य साधुत्वं द्रष्टव्यम् ॥

(उद्योतः) **दर्शनं चक्षुरिति** । करणे ल्युडिति भावः ॥ **तेजोरूपमिति** । अपक्रमणसामर्थ्यमनेन दर्शितम् । विषयग्राहिणो नयनरश्मयः सूर्यरश्मिवत् प्रासाददेशस्थपुरुषनयनादपक्रम्य यावद्विषयदेशं गच्छन्तीत्यर्थः । एवं प्रासादात् प्रेक्षते चक्षुः प्रासादादपक्रम्य विषयं जानीते इत्यर्थः । प्रासादस्थपुरुषान्निर्गमनं प्रासादादिति व्यवह्रियते इति बोध्यम् । प्रासादमारुह्य भुङ्क्ते इत्याद्यर्थे प्रासादात् भुङ्क्ते इत्यादीनामनभिधानमिति बोध्यम् । प्रासादस्थपात्राद्विर्गतमन्नं भुङ्क्ते इति भाष्यरीत्यार्थं इत्यन्ये ॥ **प्राप्यविषयग्राहित्वादिति** । परापरयोगे चेति क्त्वा । बौद्धे यथाकथंचिद्विभागो बोध्यः ॥ भाष्ये—**अन्याचान्याचेति** । दर्शनक्रियेत्यर्थः ॥ **अपक्रामति चक्षुर्दर्शनमिति** दर्शनपदेन वृत्तिरेवाभिमता । कैयटोक्तव्याख्याने तु चक्षुर्व्यक्तिरिति विशेष्यं बोध्यम् ॥ वृत्तिपरत्वेन व्याख्याने चिरं ज्ञानानुभवानापत्तिरिति पूर्वपक्षः । तावत्कालं स्थिरत्वेनाप्युत्तरं द्वितीयं तु स्पष्टमेवेति ध्येयम् ॥ सत्यपि द्वित्वे विभक्त्यन्तस्यैव द्वित्वापत्तेः कर्मव्यतिहाराभावेन समासवद्भावाप्राप्तेरेकशेषेण बाधाच्च द्वन्द्वाप्राप्तौ कथमन्यान्येतीत्यत आह—**भाष्यकारेति** । तत्प्रामाण्यात्कर्मव्यतिहाराभावेपि बहुलग्रहणात् क्वचित्समासवद्भाव इत्यर्थः ॥ कृतवीप्साद्विर्वचनस्यान्यस्येत्यस्य प्रादुर्भावशब्देन षष्ठीसमास इति परे ॥

(तृतीयवार्तिकप्रत्याख्यानभाष्यम्)

प्रश्नाख्यानयोश्च पञ्चमी वक्तव्येति । इदमत्र प्रयोक्तव्यं सत्र प्रयुज्यते—कुतो भवानागच्छतीति, पाटलिपुत्रादागच्छामीति ॥

(प्रदीपः) **इदमत्रेति** । प्रतीयमानत्वादर्थस्य शब्दाप्रयोगः ॥

(चतुर्थवार्तिकप्रत्याख्यानभाष्यम्)

यतश्चाध्वकालनिर्माणं तत्र पञ्चमी वक्तव्येति । इदमत्र प्रयोक्तव्यं सत्र प्रयुज्यते—गवीधुमतो निःसृत्य सांकाश्यं चत्वारि योजनानि । कार्तिक्या आग्रहायणी मास इति । इदमत्र प्रयोक्तव्यं सत्र प्रयुज्यते—कार्तिक्याः प्रभृत्याग्रहायणी मास इति॥

(प्रदीपः) **कार्तिक्याः प्रभृतीति** । तत आरभ्येत्यर्थः । भाष्यकारवचनात्प्रभृतियोगे पञ्चमी ॥

(उद्योतः) प्रभृतिपदप्रयोगेपि तदर्थयोगेपि वा कथं पञ्चमीत्यत आह—**भाष्यकारवचनादिति** । इदमत्र प्रयोक्तव्यं सत्र प्रयुज्यते इत्येवंरूपात्प्रभृतियोगे पञ्चमीति वचनमनुमीयते इति भावः ॥ **न प्रयुज्यते** इत्युक्त्या प्रभृत्यर्थयोगे पञ्चमीति सूचितम् ॥ तदप्यवधिमादायेत्येवंरूपप्रभृत्यर्थयोग एव प्रवर्तते । प्रभृतिशब्दस्य आरभ्येत्यस्य च तमादायेत्यर्थः ॥

(पञ्चमवार्तिकप्रत्याख्यानभाष्यम्)

तद्युक्तात्काले सप्तमी वक्तव्येति । इदमत्र प्रयोक्तव्यं सत्र प्रयुज्यते—कार्तिक्याः प्रभृति आग्रहायणी गते मास इति ॥

(प्रदीपः) **गते मास इति** । ततश्च यस्य च भावेनेति सिद्धा सप्तमी ॥

(उद्योतः) अधिकरणत्वाभावात्कथं सप्तमीत्यत आह—**ततश्चेति** । कार्तिकीमादाय मासे गते आग्रहायणी भवतीति वाक्यार्थ इति भावः ॥

(षष्ठवार्तिकप्रत्याख्यानभाष्यम्)

अध्वनः प्रथमा च सप्तमी चेति । इदमत्र प्रयोक्तव्यं सत्र प्रयुज्यते—गवीधुमतो निःसृत्य यदा चत्वारि योजनानि गतानि भवन्ति, ततः सांकाश्यम् । चतुर्षु योजनेषु गतेषु ततः सांकाश्यमिति ॥ अपादाने ॥ २८ ॥

(प्रदीपः) **चत्वारीति** । तत्र प्रातिपदिकार्थस्याव्यतिरेकात्सिद्धा प्रथमा ॥ २८ ॥

(उद्योतः) तत्र प्रातीति । एतदर्थमेव ततः **सांकाश्यमिति** वाक्यभेद इति भावः ॥ २८ ॥

(३१३ उपपदपञ्चमीसूत्रम् ॥ २ । ३ । २ आ. ८ ॥)

४८७ अन्यारादितरर्तेदिक्शब्दाञ्चूत्तरपदाजाहियुक्ते ॥ २।३।२९ ॥

(आक्षेपभाष्यम्)

अञ्चूत्तरपदग्रहणं किमर्थम् । न दिक्शब्दैर्योग इत्येव सिद्धम् ? ॥

(समाधानभाष्यम्)

"षष्ठ्यतसर्थप्रत्ययेन" इति वक्ष्यति, तस्यायं पुरस्तादपकर्षः ॥ अन्यारा ॥ २९ ॥

(प्रदीपः) **अन्यारात्** ॥ २९ ॥ **तस्यायमिति** । अथ सध्यङ् देवदत्तेनेत्यदिक्शब्दार्थमञ्चूत्तरपदग्रहणं कस्मान्न विज्ञायते । उच्यते—दिक्शब्दसाहचर्यादञ्चूत्तरपदस्यापि दिक्शब्दस्यैव ग्रहणं नान्यस्य ॥ २९ ॥

(३१४ उपपदविभक्तिसूत्रम् ॥ २ । ३ । २ आ. ९ ॥)

४८८ षष्ठ्यतसर्थप्रत्ययेन ॥ २।३।३० ॥

(पदकृत्याधिकरणम्)

(आक्षेपभाष्यम्)

अर्थग्रहणं किमर्थम् ? ॥

(प्रदीपः) **षष्ठ्यत** ॥ ३० ॥ **अर्थग्रहणमिति** । अ-

तसुशब्दः प्रत्ययत्वं न व्यभिचरतीति प्रत्ययग्रहणादतसुशब्दस्तदर्थोपलक्षणं विज्ञास्यत इति प्रश्नः ॥

(उद्द्योतः) षष्ठ्यतस ॥ ३० ॥ तदर्थोपलक्षणमिति। मध्यमपदलोपिसमासादिति भावः ॥

(समाधानभाष्यम्)

'षष्ठ्यतस्प्रत्ययेन' इत्युच्यमाने इहैव स्यात्—दक्षिणतो ग्रामस्य उत्तरतो ग्रामस्येति, इह न स्यात्—उपरि ग्रामस्य उपरिष्टाद् ग्रामस्येति। अर्थग्रहणे पुनः क्रियमाणे अतस्प्रत्ययेन च सिद्धं भवति—यश्चान्यस्तेन समानार्थः ॥

(प्रदीपः) षष्ठ्यतस्प्रत्ययेनेति। अतसुशब्दस्यार्थस्याश्रयितुमशक्यत्वात्। तस्यतेर्नञ्पूर्वस्य क्विप्यतसिति रूपसंभवाच्च॥

(उद्द्योतः) अतसशब्दस्यार्थस्येति व्यधिकरणषष्ठ्योराश्रयणाशक्यत्वे हेतुं दर्शयन् अतसुशब्दे प्रत्ययत्वव्यभिचारं दर्शयति—तस्यतेरिति ॥ न च प्रत्ययाप्रत्यययोरिति परिभाषयाङ्गस्येति सूत्रभाष्यपठितया, प्रतिपदोक्तपरिभाषया च प्रत्ययस्यैव लाभे सिद्धे प्रत्ययग्रहणेन सामर्थ्यात्तदर्थलाभ इति वाच्यम्। तदनित्यत्वज्ञापनेनापि चारितार्थ्यात् ॥ संभवाच्चेति। चो हेतौ॥ भाष्ये—अन्यस्तेन समानार्थ इत्यस्य तेनापि योगे सिद्धमिति शेषः ॥

(आक्षेपभाष्यम्)

अथ प्रत्ययग्रहणं किमर्थम्? ॥

(उद्द्योतः) अथ प्रत्ययेति। परिभाषयैव सिद्धे इत्यर्थः ॥

(समाधानभाष्यम्)

इह मा भूत्—प्राग्ग्रामात्, प्रत्यग्ग्रामात् ॥

(प्रदीपः) प्राग्ग्रामादिति। प्रत्ययग्रहणमधिकं क्रियमाणं श्रूयमाणप्रत्ययग्रहणार्थं विज्ञास्यत इति लुप्तेऽस्तातौ षष्ठ्यभावः ॥

(उद्द्योतः) लुप्तेपि प्रत्ययलक्षणेन प्रत्ययान्तत्वमस्त्येवेत्यत आह—प्रत्ययग्रहणमिति। अञ्चेर्लुगिति लुक् ॥ ३० ॥

(उपसंहारभाष्यम्)

अञ्चूत्तरपदस्याप्येतत्प्रयोजनमुक्तम्। तत्रान्यतरच्छक्यमवक्तुम् ॥ षष्ठ्यतस ॥ ३० ॥

(प्रदीपः) तत्रान्यतरदिति। एकप्रयोजनत्वात् ॥ ३० ॥

(३१५ उपपदतृतीयापञ्चमीसूत्रम् ॥ २। ३। २ आ. १०)

४९० पृथग्विनानानाभिस्तृतीयाऽन्यतरस्याम् ॥ २।३।३२ ॥

(पञ्चमीसाधनाधिकरणम्)

(१५०६ वार्तिकप्रथमखण्डम् ॥ १)

॥ * ॥ पृथगादिषु पञ्चमीविधानम् ॥ * ॥

(भाष्यम्) **पृथगादिषु पञ्चमी विधेया—पृथग् देवदत्तात् ॥**

(प्रदीपः) पृथग्विना ॥ ३२ ॥ अन्यतरस्यांग्रहणेन पक्षे यथाप्राप्ताभ्यनुज्ञानं क्रियते। न चात्र पञ्चमी प्राप्तेति मत्वाह—पृथगादिष्विति। पक्ष इति वाक्यशेषः ॥

(आक्षेपभाष्यम्)

किमर्थं न प्रकृतं पञ्चमीग्रहणमनुवर्तते? । क्व प्रकृतम्? । "अपादाने पञ्चमी" इति ॥

(प्रदीपः) न प्रकृतमिति। नशब्दः काक्का प्रयुक्तः। प्रकृतमेवेत्यर्थः ॥

(उद्द्योतः) पृथग्विना ॥ ३२ ॥ नञः प्रतिषेधार्थत्वेऽसंगतिरत आह—काक्केति ॥

(१५०७ वार्तिकद्वितीयखण्डम् ॥ २)

॥ * ॥ अनधिकारात् ॥ * ॥

अनधिकारः सः ॥

(प्रदीपः) अनधिकार इति। अन्याराादिति योगात्परेषु योगेषु नाधिक्रियत इत्यर्थः ॥

(उद्द्योतः) अनधिकारत्वेऽन्यारादित्यस्यासंगतिरत आह—योगात्परेष्विति ॥

(१५०८ वार्तिकतृतीयखण्डम् ॥ ३)

॥ * ॥ अधिकारे हि द्वितीयाषष्ठीविषये प्रतिषेधः ॥ * ॥

(भाष्यम्) **अधिकारे हि द्वितीयाषष्ठीविषये प्रतिषेधो वक्तव्यः स्यात्। दक्षिणेन ग्रामम्, दक्षिणतो ग्रामस्येति ॥**

(उद्द्योतः) भाष्ये—द्वितीयाषष्ठीविषये इति। एनपा षष्ठ्यतसर्थेत्यत्र चेत्यर्थः ॥ सौत्रक्रमत्यागे न्यायसिद्धपूर्वनिपातत्यागे च बीजं चिन्त्यम् ॥ केचित्तु—'एनपा द्वितीया' 'षष्ठ्यतसर्थेनेत्याष्टाध्यायीपाठः। एवं च पृथग्विनेत्यनेन द्वितीयाविधानमपीति, एनपेति योगविभागात्षष्ठ्यपीति च वृत्त्युक्तं चिन्त्यमित्याहुः ॥

(वार्तिकप्रत्याख्यानभाष्यम्)

एवं तर्हि—अन्यतरस्यांग्रहणसामर्थ्यात्पञ्चमी भविष्यति ॥

(प्रदीपः) एवं तर्हीति। अन्यतरस्यांग्रहणं पक्षे विभक्त्यन्तरप्रापणार्थं सव्यवहितामपि पञ्चमीं प्रापयिष्यतीत्यर्थः ॥

(उद्द्योतः) अन्यतरस्यांग्रहणमिति। अव्ययानामनेकार्थत्वात्समुच्चयबोधनद्वारेत्यर्थः ॥

(सामर्थ्यनिराकरणभाष्यम्)

अस्त्यन्यदन्यतरस्यांग्रहणस्य प्रयोजनम् ॥ किम्?। यस्यां नाप्राप्तायां तृतीयारभ्यते सा यथा स्यात् ॥ कस्यां च नाप्राप्तायाम्? । अन्ततः षष्ठ्याम् ॥

(प्रदीपः) अस्त्यन्यदिति । यथाप्राप्ताभ्यनुज्ञानं हि विकल्पेन कार्यं न तु यस्य कस्यचिदिति भावः ॥ अन्तत इति । अवसानत इत्यर्थः । यत्र ह्यन्या विभक्तिर्न विहिता सा शेषत्वात् षष्ठ्यां विषयः ॥ [यथाप्राप्ताभ्यनुज्ञानं विकल्पेन विधीयते । प्राप्त्यभावे भवेत् षष्ठी । सा हि शेषनिबन्धना ॥]

(उद्द्योतः) आशयानभिज्ञः शङ्कते—भाष्ये—अस्त्यन्यदिति ॥

(आक्षेपभाष्यम्)

तर्त्तर्हि वक्तव्यम्? ॥

(समाधानभाष्यम्)

न वक्तव्यम् । प्रकृतमनुवर्तते । क्व प्रकृतम्? । "अपादाने पञ्चमी" इति ॥

(आक्षेपस्मारणभाष्यम्)

ननु—चोक्तम् अनधिकारः सः * अधिकारे हि द्वितीयाषष्ठीविषये प्रतिषेधः * इति ॥

(समाधानभाष्यम्)

एवं तर्हि संबन्धमनुवर्तिष्यते—"अपादाने पञ्चमी" । अन्यारादितरर्तेदिक्शब्दाञ्चूत्तरपदाजाहियुक्ते" पञ्चमी । "षष्ठ्यतसर्थप्रत्ययेन" अन्यारादिभिर्योगे पञ्चमी । "एनपा द्वितीया" अन्यारादिभिर्योगे पञ्चमी । "पृथग्विनानानाभिस्तृतीयान्यतरस्याम्" पञ्चमीग्रहणमनुवर्तते, 'अन्यारादिभिर्योगे' इति निवृत्तम् ॥

(प्रदीपः) संबन्धमिति । अन्यादिग्रहणसंबद्धमित्यर्थः ॥

(समाधानान्तरभाष्यम्)

अथ वा मण्डूकप्लुतयोधिकाराः । तद्यथा—मण्डूका उत्प्लुत्योत्प्लुत्य गच्छन्ति तद्वदधिकाराः ॥

(भाष्यम्) अथ वा—

(१५०९ वार्तिकम् ४ ॥)

*** अन्यवचनाच्चकाराकरणात्प्रकृतस्यापवादो विज्ञायते यथोत्सर्गेण प्रसक्तस्य * ॥**

(भाष्यम्) **अन्यस्या विभक्तेर्वचनाच्चकारस्यानुकर्षणार्थस्याकरणात्प्रकृतायाः पञ्चम्या द्वितीयाषष्ठ्यौ बाधिके भविष्यतः । यथोत्सर्गेण प्रसक्तस्यापवादो बाधको भवति ॥**

(प्रदीपः) यथोत्सर्गेणेति । पञ्चमी किमुत्तरार्थोऽतेहार्थापीति संदिग्धा षष्ठीद्वितीयाभ्यामसंदिग्धाभ्यां बाध्यत इत्यर्थः ॥ ३२ ॥

(उद्द्योतः) यद्यपि संबन्धानुवृत्तौ मण्डूकानुवृत्तौ वाऽनुवृत्तिसामर्थ्यादेव पञ्चम्यामपि सिद्धायाम् अन्यतरस्यांग्रहणं चिन्त्यप्रयोजनम्, षष्ठी तु नेष्यते भाष्यकृता । तथापि तद्विना तयोर्द्वैयत्वात्तद्बोधनायैव तद्ग्रहणमिति बोध्यं तद्ज्ञनयत्रेवाथवान्येलादिपक्षद्वयमाह ॥ बाध्यते इति । इह तु तृतीयया न बाध्यते, चस्तानीयान्यतरस्यांग्रहणादिति भावः ॥

(समाधानान्तरभाष्यम्)

अथ वा वक्ष्यत्येतत्—"अनुवर्तन्ते च नाम विधयः । न चानुवर्तनादेव भवन्ति । किं तर्हि? यत्नाद्भवन्ति" इति ॥ पृथग्विना ॥ ३२ ॥

(उद्द्योतः) भाष्ये यत्नादिति । अत्र चान्यतरस्यांग्रहणं यत्नोऽस्तीति भावः ॥ ३२ ॥

(३१६ उपपदसूत्रम् ॥ २ । ३ । २ आ. ११)

४९३ दूरान्तिकार्थेभ्यो द्वितीया च ॥ २।३।३५ ॥

(१५१० आक्षेपवार्तिकम् ॥ १)

॥ * ॥ दूरान्तिकार्थेभ्यः पञ्चमीविधाने तद्युक्तात्पञ्चमीप्रतिषेधः ॥ * ॥

(भाष्यम्) **दूरान्तिकार्थेभ्यः पञ्चमीविधाने तद्युक्तात्पञ्चम्याः प्रतिषेधो वक्तव्यः । दूराद्ग्रामस्य ॥**

(प्रदीपः) दूरान्ति ॥ ३५ ॥ तद्युक्तादिति । दूरान्तिकार्थैर्युक्तं यदपेक्षया दूरान्तिकत्वं तद्वाचिन इत्यर्थः ॥ दूराद्ग्रामस्येति । पूर्वसूत्रेण षष्ठ्येव ग्रामाद्भवति ॥

(उद्द्योतः) दूरान्तिकार्थेभ्यो ॥ ३५ ॥ भाष्ये पञ्चमीविधाने तद्युक्तादिति । पञ्चम्यन्तदूरान्तिकार्थैर्युक्तादित्यर्थः । सामान्यतो दूरान्तिकार्थयुक्तात्प्रतिषेधे पूर्वसूत्रस्थान्यतरस्यांग्रहणस्य वैयर्थ्यापत्तिरत एवात्र वार्त्तिके पञ्चमीविधान इति सार्थकं दूरान्तिकार्थैरिति पूर्वसूत्रेण षष्ठीपञ्चम्योः प्राप्तिः ॥ पूर्वसूत्रेण । दूरान्तिकार्थैः षष्ठीत्यनेन ॥ षष्ठ्येवेति । ननु पञ्चमी अनेन निषेधादितिभावः ॥

(१५११ आक्षेपबाधकवार्तिकम् ॥ २)

॥*॥ न वा तत्रापि दर्शनादप्रतिषेधः॥*॥

(भाष्यम्) **अनर्थकः प्रतिषेधोऽप्रतिषेधः । न वा तत्रापि दर्शनात्पञ्चम्याः प्रतिषेधोनर्थकः । तत्रापि हि पञ्चमी दृश्यते—**

दूरादावसथान्मूत्रं दूरात्पादावसेचनम् ॥
दूराच्च भाव्यं दस्युभ्यो दूराच्च कुपिताद् गुरोः॥

दूरान्ति ॥ ३५ ॥

(प्रदीपः) दूरादावसथादिति । आवसथस्य दूर इत्यर्थः । पूर्वसूत्रेणावसथादेः पञ्चम्यपि भवति ॥ ३५ ॥

(उद्द्योतः) दूरादावसथादित्यनयोः सामानाधिकरण्यभ्रमं निराकरोति—आवसथस्येति । दूरात् ग्रामस्येत्यादौ त्वनभिधानात्पञ्चमी नेति भावः ॥ ३५ ॥

(३१७ कारकसप्तमीसूत्रम् ॥ २ । ३ । २ आ. १२)

४९४ सप्तम्यधिकरणे च ॥ २।३।३६ ॥

(न्यूनतापूरणाधिकरणम्)

(१५१२ सप्तमीविधानवार्तिकम् ॥ १)

॥ * ॥ सप्तमीविधाने क्तस्येन्विषयस्य कर्मण्युपसंख्यानम् ॥ * ॥

(भाष्यम्) **सप्तमीविधाने क्तस्येन्विषयस्य कर्मण्युपसंख्यानं कर्तव्यम् । अधीती व्याकरणे । परिगणिती याज्ञिक्ये । आम्नाती छन्दसि ॥**

सप्तम्यधि ॥ ३६ ॥ **क्तस्येन्विषयस्येति** । इन्नन्तस्येत्यर्थः ॥ **अधीतीति** । अधीतमनेनेतीष्टादिभ्य इतीनिः । अत्र व्याकरणस्य कर्मत्वाद् द्वितीया प्राप्नोति यथा कृतपूर्वी कटमिति । ततस्तदपवादः सप्तमी विधीयते ॥ अधिकरणविवक्षया सिद्धेति चेत् । कर्मविवक्षया द्वितीयापि स्यादिति तन्निवृत्त्यर्थं कर्तव्यमेव वचनम् । मासमधीती व्याकरण इति कालकर्मणो बहिरङ्गत्वादिष्टाग्रहणात्सप्तम्यभावः ॥

(उद्द्योतः) **सप्तम्य** ॥ ३६ ॥ इन्विषयस्येत्यस्य इनो विषयस्येति समासः । प्रकृतित्वेन च स इनो विषयस्तदाह—**इन्नन्तस्येति** । क्तान्तप्रकृतिकेनन्तस्येत्यर्थः ॥ **अत्र व्याकरणस्येति** । पूर्वमविवक्षितकर्मतया भावे क्ते पश्चात्कर्मसंबन्धेन कर्मणोऽनभिहितत्वाद् द्वितीया प्राप्तेत्याशयः । कर्मणि क्तप्रत्ययान्तात्तु वा(ऽ)इनिरव्यभिचारन्यायात् ॥ एतेन कर्मणि क्तप्रत्यये व्याकरणशब्दात् प्रथमैवेति निरस्तम् ॥ **अधिकरणत्वविवक्षायामिति** । अस्तीत्यध्याहारेण कर्तृद्वारा व्यापाराश्रयत्वविवक्षायामित्यर्थः ॥ **बहिरङ्गत्वादिति** । तच्चोपपादितं कालाध्वनोरित्यत्र ॥

(१५१३ सप्तमीविधानवार्तिकम् ॥ २)

॥ * ॥ साध्वसाधुप्रयोगे च ॥ * ॥

(भाष्यम्) **साध्वसाधुप्रयोगे च सप्तमी वक्तव्या । साधुर्देवदत्तो मातरि । असाधुः पितरि ॥**

(प्रदीपः) **साध्वसाधुप्रयोगे चेति । साधुनिपुणाभ्यां** [इति] सप्तम्यां सिद्धायामनर्चार्थमत्र साधुग्रहणम् । तेन तत्त्वकथनेपि साधुयोगे सप्तमी भवति । अर्चाग्रहणं तु तत्र निपुणविशेषणार्थमेव । साधुर्भृत्यो राज्ञ इति तु भृत्यापेक्षा षष्ठी, न तु साध्वपेक्षेति वाक्यार्थज्ञा आहुः ॥

(उद्द्योतः) उभयत्रानेनैव सप्तम्यां सिद्धायामर्चाग्रहणं तत्र व्यर्थमत आह—**अर्चाग्रहणं त्विति** । तत्र साधुग्रहणं तु साधुप्रयोगेऽप्यर्चायां प्रत्यादियोगे निषेधार्थम् । न चानेन दुर्वारा । तस्यासामर्थ्येनासाप्यप्रवृत्तेरिति केचित् ॥

(१५१४ सप्तमीविधायकवार्तिकम् ॥ ३)

॥ * ॥ कारकार्हाणां च कारकत्वे ॥ * ॥

(भाष्यम्) **कारकार्हाणां च कारकत्वे सप्तमी वक्तव्या । ऋद्धेषु भुञ्जानेषु दरिद्रा आसते । ब्राह्मणेषु तरत्सु वृषला आसते ॥**

(प्रदीपः) **कारकार्हाणां चेति** । कारकशब्दो भावप्रधानः । तेन कारकत्वमर्हन्तीत्यर्थः ॥ **ऋद्धेष्विति । ऋद्धा** भोजनक्रियामर्हन्तीति कारकार्हाः । लक्ष्यलक्षणभावाविवक्षायामपि यथा स्यादिति वचनम् । तद्विवक्षायामुत्तरसूत्रेण सिद्धत्वात् ॥

(उद्द्योतः) क्रियाया एव कारकार्हत्वादसङ्गतिमाशङ्क्याह—**कारकशब्द इति** । शक्तिपरः स इति परे ॥ उत्तरसूत्रेण 'यस्य च भावेन' इत्यनेन ॥

(१५१५ सप्तमीविधायकवार्तिकम् ॥ ४)

॥ * ॥ अकारकार्हाणां चाकारकत्वे ॥ * ॥

(भाष्यम्) **अकारकार्हाणां चाकारकत्वे सप्तमी वक्तव्या । मूर्खेष्वासीनेषु ऋद्धा भुञ्जते । वृषलेष्वासीनेषु ब्राह्मणास्तरन्ति ॥**

(प्रदीपः) **मूर्खेष्विति । मूर्खा** भोजनानर्हत्वादकारकार्हाः ॥

(उद्द्योतः) भाष्ये ऋद्धा इत्यस्य विद्यादिगुणसमृद्धा इत्यर्थः ॥

(१५१६ सप्तमीविधायकवार्तिकम् ॥ ५)

॥ * ॥ तद्विपर्यासे च ॥ * ॥

(भाष्यम्) **तद्विपर्यासे च सप्तमी वक्तव्या । ऋद्धेष्वासीनेषु मूर्खा भुञ्जते । ब्राह्मणेष्वासीनेषु वृषलास्तरन्ति ॥**

(प्रदीपः) **तद्विपर्यास इति** । यदा कारकार्हाणां नास्ति कारकत्वमकारकार्हाणां चास्ति कारकत्वं तदेत्यर्थः ॥

(१५१७ सप्तमीविधायकवार्तिकम् ॥ ६)

॥ * ॥ निमित्तात्कर्मसंयोगे ॥ * ॥

(भाष्यम्) **निमित्तात्कर्मसंयोगे सप्तमी वक्तव्या॥**

चर्मणि द्वीपिनं हन्ति दन्तयोर्हन्ति कुञ्जरम् ॥
केशेषु चमरीं हन्ति सीम्नि पुष्कलको हतः ॥
सप्तम्यधि ॥ ३६ ॥

(प्रदीपः) निमित्तादिति । क्रियाफलमिह निमित्तत्वेन विवक्षितम् । यत् क्रियायाः प्रयोजकं यदर्थः क्रियारम्भस्ततो हेताविति तृतीयायां प्राप्तायां सप्तमी विधीयते । तस्य निमित्तस्य यदि कर्मणा संयोगः संबन्धः । ततो वेतनेन धान्यं लुनातीति सप्तमी न भवति । वेतनस्य धान्येन संयोगाभावात् ॥ ३६ ॥

(उद्द्योतः) क्रियाफलमिति । व्याख्यानादितिभावः ॥ संयोग इत्यस्य व्याख्यानं संबन्ध इति समवायस्यापि संग्रहाय ॥ ३६ ॥

(३१८ उपपदसप्तमीसूत्रम् २ । ३ । २ आ. १३)

४९५ यस्य च भावेन भावलक्षणम् ॥ २।३।३७ ॥

(भूयोदर्शनाभावेसप्तमीसाधनाधिकरणम्)

(१५१८ वार्तिकम् ॥ १)

॥ * ॥ भावलक्षणे सप्तमीविधाने अभावलक्षणे उपसंख्यानम् ॥ * ॥

(भाष्यम्) भावलक्षणे सप्तमीविधाने अभावलक्षण उपसंख्यानं कर्तव्यम्।अग्निषु हूयमानेषु गतः, हुतेष्वागतः । गोषु दुह्यमानासु गतः, दुग्धास्वागतः ॥ किं पुनः कारणं न सिध्यति ? । लक्षणं नाम तद्भवति येन पुनः पुनर्लक्ष्यते । सकृच्चासौ कथंचिदग्निषु हूयमानेषु प्रस्थितः, हुतेष्वागतः । गोषु दुह्यमानासु प्रस्थितः, दुग्धास्वागतः ॥

(प्रदीपः) यस्य च ॥ ३७ ॥ अभावलक्षण इति । भूयो दर्शनाश्रयो हि लक्ष्यलक्षणभावो यथाग्निधूमयोः । इह त्वग्निषु हूयमानेषु प्रस्थित इत्यग्निहवनं प्रस्थानेन सह यदा पुनः पुनर्न दृष्टं तदा न तत्तस्य लक्षणमिति वचनारम्भः ॥

(उद्द्योतः) यस्य च ॥ ३७ ॥ भूय इति । अनुमापकत्वं लक्षणत्वम् । तत्प्रकारको बोध इति पूर्वपक्ष इति भावः ॥ यथाग्नीति । तथा च—उदयति सवितरि तमो नष्टम्' 'धूमे सति वह्निर्भवतीत्यादावेव स्यात् इति भावः ॥

(१५१२न्यासान्तरेण समाधानवार्तिकम् २)

॥ * ॥ सिद्धं तु भावप्रवृत्तौ यस्य भावारम्भवचनात् ॥ * ॥

(भाष्यम्) सिद्धमेतत् । कथम् ? । यस्य भावप्रवृत्तौ द्वितीयो भाव आरभ्यते तत्र सप्तमी वक्तव्या॥

(उद्द्योतः) भाष्ये द्वितीयो भाव आरभ्यते । इत्यस्योच्यत इत्यर्थः ॥

(आक्षेपभाष्यम्)

सिध्यति । सूत्रं तर्हि भिद्यते ॥

(समाधानभाष्यम्)

यथान्यासमेवास्तु ॥

(आक्षेपस्मारणभाष्यम्)

ननु चोक्तम्—*भावलक्षणे सप्तमीविधानेऽभावलक्षण उपसंख्यानम् * इति ॥

(समाधानभाष्यम्)

नैष दोषः । न खल्ववश्यं तदेव लक्षणं भवति येन पुनःपुनर्लक्ष्यते । सकृदपि यन्निमित्तत्वाय कल्पते तदपि लक्षणं भवति । तद्यथा—अपि भवान्कमण्डलुपाणिं छात्रमद्राक्षीदिति । सकृदसौ कमण्डलुपाणिर्दृष्टश्छात्रस्तस्य तदेव लक्षणं भवति ॥ यस्य च ॥ ३७॥

(प्रदीपः) सकृदपीति । लक्षणशब्दः क्रियानिमित्तकः—लक्ष्यते अनेनेति लक्षणम् । यच्च निर्ज्ञातकालं हवनादिकमनिर्ज्ञातकालस्य सकृदपि कालपरिच्छेदनिमित्तं भवति तत्तस्य लक्षणमित्यर्थः ॥ ३७ ॥

(उद्द्योतः) लक्षणशब्दइति। नायं शब्दोऽनुमापकत्वेनाभिमतलिङ्गपर्यायः। किन्तु वृक्षं प्रति विद्योतत इत्यादाविवानिर्ज्ञातज्ञापनवृत्तिरिति भावः ॥ भाष्ये—सकृदपि यन्निमित्तत्वायेति। तत्कालादिपरिछेदनिमित्तत्वायेत्यर्थः ॥ तदेव कमण्डलुपाणित्वमेव ॥ अनिर्ज्ञातकालस्येति । अनेन मानान्तरेण यस्य स्वरूपं ज्ञातं तस्य कालविशेषज्ञापनार्थं शब्दप्रयोगे एकस्य प्रवृत्तिं सूचयति ॥ राहूपरागे स्नायादित्यादौ कालवाचकादधिकरणे एव ॥ ३७ ॥

(३१९ उपपदपञ्चमीसूत्रम् ॥ २ । ३ । २ आ. १४)

५०० पञ्चमी विभक्ते २ । ३ । ४२ ॥

(विभक्तशब्दार्थनिर्णयाधिकरणम्)

(आक्षेपभाष्यम्)

इह कस्मान्न भवति—कृष्णा गवां संपन्नक्षीरतमेति ? ॥

(प्रदीपः) पञ्चमी ॥ ४२ ॥ कृष्णा गवामिति । गोमण्डलात् कृष्णा गौः पृथक् क्रियत इत्यस्ति विभक्तत्वम् ॥

(उद्द्योतः) पञ्चमी विभक्ते ॥ ४२ ॥ विभागो भेदः । गोभ्यो गौरेव कथं विभक्तत्वमत आह—गोमण्डलादिति । पृथक् क्रियते भेदेन बोध्यते ॥

(समाधानभाष्यम्)

विभक्त इत्युच्यते । न चैतद्विभक्तम् ॥

(प्रदीपः) न चैतदिति। कृष्णाया गोगोत्वेन गोष्वन्तर्भावात्॥

(समाधानबाधकभाष्यम्)

विभक्तमेतत्। गोभ्यः कृष्णा विभज्यते॥

(समाधानाशयभाष्यम्)

विभक्तमेव यन्नित्यं तत्र भवितव्यम्। न चैतन्नित्यं विभक्तम्॥

(आक्षेपभाष्यम्)

किं वक्तव्यमेतत्?॥

(समाधानभाष्यम्)

नहि॥ कथमनुच्यमानं गंस्यते?। विभक्तग्रहणसामर्थ्यात्। यदि यद्विभक्तं चाविभक्तं च तत्र स्याद्, विभक्तग्रहणमनर्थकं स्यात्। पञ्चमी॥४२॥

(प्रदीपः) विभक्तग्रहणमिति॥ सर्वत्रैव निर्धारणे विभागसद्भावात् पूर्वत्रैव पञ्चमीग्रहणं कुर्यात्। तस्माद्विभक्तग्रहणसामर्थ्याद् अवधारणमाश्रीयत इत्यर्थः॥४२॥

(उद्द्योतः) अवधारणमाश्रीयत इति। माथुराः पाटलिपुत्रकेभ्य इत्यादौ माथुराणां पाटलिपुत्रकेषु प्राणित्वेनान्तर्भावेपि शब्दोपात्ताकारापेक्षयानन्तर्भावाद्विभाग एवेति भावः॥४२॥

(३२० उपपदसप्तमीसूत्रम्॥ २।३।२ आ. १५)

५०१ साधुनिपुणाभ्यामर्चायां सप्तम्यप्रतेः॥ २। ३। ४३॥

(न्यूनतापूर्त्यधिकरणम्)

(१५२० वार्तिकम्॥ १)

[॥ * ॥ अप्रत्यादिभिः॥ * ॥]

(भाष्यम्) अप्रत्यादिभिरिति वक्तव्यम्। इहापि यथा स्यात्-[साधुर्देवदत्तो मातरं प्रति।] मातरं परि। मातरमनु। साधु॥४३॥

(प्रदीपः) साधुनि॥४३॥ अप्रत्यादिभिरिति। प्रतिपर्यनवः प्रत्यादयः॥४३॥

(उद्द्योतः) साधुनि॥४३॥ प्रतिपरीति। कर्मप्रवचनीयसंज्ञासमस्थाः प्रत्यादय इति भावः॥४३॥

(३२१ उपपदतृतीयासप्तमीसूत्रम्॥ २।३।२ आ. १६)

५०२ प्रसितोत्सुकाभ्यां तृतीया च॥ २। ३। ४४॥

(प्रसितशब्दार्थनिर्णयाधिकरणम्)

(आक्षेपभाष्यम्)

प्रसित इत्युच्यते। कः प्रसितो नाम?॥

(प्रदीपः) प्रसितो॥४४॥ कः प्रसित इति। किं प्रकृष्टः शुक्लः प्रसितः, उत सवतेस्सिनोतेर्वा कारकमिति प्रश्नः॥

(उद्द्योतः) प्रसितोत्सु॥४४॥ सवतेरिति। षतिस्यतीत्त्वे कृतेऽस्य सितमिति। कारकं कर्मकारकम्॥

(समाधानभाष्यम्)

यस्तत्र नित्यं प्रतिबद्धः॥ कुत एतत्?। सिनोतिरयं बध्नात्यर्थे वर्तते—बद्ध इवासौ तत्र भवति॥ प्रसितो॥४४॥

(प्रदीपः) यस्तत्रेति। उत्सुकशब्दसाहचर्यात् तदर्थसदृशोर्थो गृह्यते॥ बद्ध इवेति। मुख्यस्य व्यतिषङ्गरूपस्य बन्धनस्याभावात् सादृश्याद् गौणार्थपरिग्रहः॥४४॥

(उद्द्योतः) व्यतिषङ्गो रज्ज्वादिभिः सम्बन्धनम्॥ गौणार्थस्तत्परत्वरूपः। अत एव पूर्वमुत्सुकसाहचर्यादित्युक्तम्॥ 'तत्परे प्रसितासक्तौ' इत्यमरः॥४४॥

(३२२ कारकसप्तमीसूत्रम्॥ २।३।२ आ. १७ सू.)

५०३ नक्षत्रे च लुपि॥ २।३।४५॥

(अनिष्टापत्तिवारणाधिकरणम्)

(आक्षेपभाष्यम्)

इह कस्मान्न भवति—अद्य पुष्यः अद्य मघा?॥

(प्रदीपः) नक्षत्रे च॥४५॥ अद्य पुष्य इति। पुष्येण युक्तः काल इत्यणो लुब्विशेष इति लुप्॥ ननु परत्वादत्र प्रथमा भविष्यति। नैतदस्ति। सर्वविभक्त्यपवादोयं विज्ञायेत। अन्तरङ्गत्वाद्वा प्रातिपदिकार्थमात्र एवेदं विधानं स्यात्॥४५॥

(उद्द्योतः) नक्षत्रे च॥४५॥ एतत्सूत्रमासवे प्रक्रियामाह—पुष्येण युक्त इति॥ सर्वेति। ततश्च पुष्यं प्रतीक्षते पुष्याय स्पृहयति पुष्यस्य समीप इत्यादि प्रयोगा न सिध्येरन्निति भाव इति सर्वं निर्मलम्॥४५॥

(समाधानभाष्यम्)

अधिकरण इति वर्तते ॥ नक्षत्रे ॥ ४५ ॥

इति श्रीमद्भगवत्पतञ्जलिविरचिते व्याकरणमहाभाष्ये द्वितीयस्याध्यायस्य तृतीयपादे द्वितीयमाह्निकम् ॥

इत्युपाध्यायजैयटपुत्रकैयटकृते महाभाष्यप्रदीपे द्वितीयस्याध्यायस्य तृतीये पादे द्वितीयमाह्निकम् ॥

इति शिवभट्टसुतसतीगर्भजनागेशभट्टविरचिते भाष्यप्रदीपोद्द्योते द्वितीयाध्यायस्य तृतीये पादे द्वितीयमाह्निकम् ॥

द्वितीयाध्यायस्य तृतीयपादे तृतीयमाह्निकम् ॥

(३२३ प्रथमासूत्रम् ॥ २ । ३ । ३ आ. १)

५०४ प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा ॥ २ । ३ । ४६ ॥

(प्रातिपदिकपदप्रयोजनाधिकरणम्)

(आक्षेपभाष्यम्)

प्रातिपदिकग्रहणं किमर्थम्? ॥

(प्रदीपः) **प्रातिपदिकार्थ ॥ ४६ ॥ प्रातिपदिकग्रहणमिति** । ङ्याप्प्रातिपदिकाद्विहितानां स्वादीनां प्रकरणमिदं नियमार्थमित्यन्तरेणापि प्रातिपदिकग्रहणं प्रातिपदिकार्थ एव प्रथमा भविष्यतीति प्रश्नः ॥

(उद्द्योतः) **प्रातिपदिकार्थ** ॥ ४६ ॥ तद्ग्रहणमन्तरा तदर्थे प्रथमानियमालाभात् प्रश्नानुपपत्तिरत आह—**ङ्यादिति** । **अन्तरेणापीति** । अर्थे इत्युक्तावपि कस्यार्थे इत्याकाङ्क्षायां संयतः स्वादिविधिस्तदर्थे इति लाभादिति भावः । तत्सत्त्वेपि लिङ्गविशिष्टपरिभाषया ङ्यन्ताद्यर्थे तल्लाभः ॥

(समाधानभाष्यम्)

उच्चैः नीचैरित्यत्रापि यथा स्यात् ॥

(प्रदीपः) **उच्चैरिति** । असति प्रातिपदिकग्रहणे अव्ययात् प्रथमा न स्यात् । **बहुषु बहुवचनमि**त्यादिनास्यैकवाक्यतायां संख्यायुक्त एव प्रातिपदिकार्थे स्यात् । प्रातिपदिकग्रहणात्तु यस्मात् संख्यारहितेप्यव्ययार्थे प्रथमा सिध्यति ॥

अथ वा लिङ्गग्रहणात् सर्वत्र प्रथमा सिध्यतीति प्रश्नः । अत एव **प्रातिपदिकार्थग्रहणं किमर्थमिति** क्वचित् पाठः । अलिङ्गेप्यव्ययार्थे यथा स्यादित्युत्तरम् ॥ प्रातिपदिकार्थश्चेह भाष्यकारेण न विचारितः । अन्वयव्यतिरेकाभ्यां यस्य यो ज्ञातस्तदर्थः प्रतीतस्तस्य सर्वस्येष्टाभिमतत्वाद्विचारे प्रयोजनाभावात् ॥

(उद्द्योतः) नन्वव्ययानामप्यर्थवत्त्वात्तेनैव सिद्धमत आह—**असतीति** । **यस्मादिति** ॥ प्रातिपदिकग्रहणसामर्थ्यादस्य संख्यावाक्यैरेकवाक्यतायामपि प्रकृतार्थापेक्षनियमाश्रयणादर्थनियमाश्रयणाद्वाऽसंख्याद्व्ययाद्वचनसिद्धिरिति भावः ॥

अथवेति । लिङ्गे वर्तमानात्प्रातिपदिकादिति सूत्रार्थः । सर्वत्र लिङ्गं प्रकृत्यर्थ इति भावः । इदं चिन्त्यं प्रातिपदिकार्थग्रहणाभावे लिङ्गमात्रे इत्यर्थापत्तौ स्त्री पुमानित्यादावेव स्यात् । न वृक्ष इत्यादौ, जात्यादेरप्यधिकस्य भानात् । तस्मादाद्यव्याख्यैव ज्यायसी ॥ **जात्यादिरिति** । **आविनाश्रयः** ॥ जातिपदं च प्रवृत्तिनिमित्तोपलक्षणम् ॥

(आक्षेपभाष्यम्)

किं पुनरत्र प्रथमया प्रार्थ्यते? ॥

(प्रदीपः) **किं पुनरिति** । **अव्ययादाप्सुप** इति लुग्विधानात् प्रथमायाः श्रवणाभावादिति भावः ॥

(समाधानभाष्यम्)

पदत्वम् ॥

(प्रदीपः) **पदत्वमिति । प्रत्ययलोपे प्रत्ययलक्षणमिति** प्रथमोत्पत्तिनिबन्धनं पदत्वं प्रार्थ्यते । तन्निबन्धनं रुत्वादिकमित्यर्थः ॥

(समाधानबाधकभाष्यम्)

नैतदस्ति । षष्ठ्यात्र पदत्वं भविष्यति ॥

(प्रदीपः) **षष्ठ्यात्रेति** । यस्मिन्नर्थे द्वितीयादयो न विहिताः स शेष इति मन्यते ॥ नन्वसंख्यत्वादव्ययार्थस्य कथं षष्ठी स्यात । नैष दोषः । एकत्वाद्यर्थनियमे षष्ठ्याः संख्यायामनियमात् । प्रत्ययनियमेपि वा तुल्यजातीयापेक्षत्वान्नियमस्यैकत्वादिभिः परस्परस्य व्यावर्तनात् ॥

(उद्द्योतः) **यस्मिन्नर्थे इति** । प्रातिपदिकार्थे प्रथमाविधानाभावात्तद्व्यतिरिक्तः शेष इति न लभ्यत इति भावः ॥ **नन्वसंख्येति** । षष्ठीविधायकस्यापि द्व्येकयोरित्यादिभिरेकवाक्यत्वादिति भावः ॥ वस्तुतो द्वितीयादीनां विषयाभावः शेषः । प्रातिपदिकार्थरूपः प्रथमाया विषयः सर्वत्रेति न तदपेक्षः शेष इत्याशयेनैकदेश्याह—षष्ठ्यात्रेति । एवं चाद्यव्याख्याने (ऽ) विनास्य भाष्यस्यासङ्गतिः ॥

(समाधानान्तरभाष्यम्)

इदं तर्हि प्रयोजनम्—ग्राम उच्चैस्तव स्वम्, ग्राम उच्चैस्ते स्वम् "सपूर्वायाः प्रथमाया विभाषा" इत्येष विधिर्यथा स्यात् ॥

(उद्द्योतः) पर एकदेश्याह—**इदं तर्हीति** । इदं सर्वमेकदेश्युक्तिरित्यग्रे स्फुटं भविष्यति ॥ उच्चैर्नीचैरित्यप्येकदेश्युक्तिः अव्ययादाप्सुप इति ज्ञापकात्सिद्धेरिति बोध्यम् ॥

(लिङ्गग्रहणप्रयोजनाधिकरणम्)

(आक्षेपभाष्यम्)

अथ लिङ्गग्रहणं किमर्थम्? ॥

(प्रदीपः) अथ लिङ्गग्रहणमिति । सत्त्वभूतार्थाभिधायीनि यानि प्रातिपदिकानि तेषां लिङ्गमप्यर्थ इति प्रश्नः ॥

(उद्द्योतः) ननु प्रातिपदिकत्वेप्यव्ययानां लिङ्गाबोधकत्वेन व्यभिचाराच्च तत्प्रातिपदिकार्थ इत्यत आह—सत्त्वभूतेति । प्रातिपदिकार्थ इत्यस्य हि तत्तत्प्रातिपदिकार्थे इत्यर्थो ननु प्रातिपदिकत्वावच्छिन्नार्थे इति असंभवादिति भावः ॥

(समाधानभाष्यम्)

स्त्री पुमान् नपुंसकमित्यत्रापि यथा स्यात् ॥

(प्रदीपः) मात्रग्रहणात्संबोधने चेति सूत्रारम्भाच्चाधिकविशेषसद्भावे प्रथमा न स्यादिति मत्वाह—स्त्रीपुमानिति । द्रव्यमत्र स्त्रीत्वाद्यधिकमभिधीयते ॥

(उद्द्योतः) अधिकविशेषेति । द्रव्यजातिभ्यामधिकेत्यर्थः ॥ स्त्रीत्वाद्यधिकमिति । स्त्रीत्वादिकमधिकं यत्रेत्यर्थः ॥

(समाधानबाधकभाष्यम्)

नैतदस्ति प्रयोजनम् । एष एव चात्रास्ति प्रातिपदिकार्थः ॥

(प्रदीपः) एष एवेति । यमर्थं प्रातिपदिकं न व्यभिचरति स प्रातिपदिकार्थः । स्त्रीत्वादिना च विना स्त्र्यादिशब्दानां प्रयोगाभावः ॥

(उद्द्योतः) यमर्थमिति । अन्वयव्यतिरेकाभ्यां यस्य प्रातिपदिकस्य योऽर्थोऽवधारितः प्रवृत्तिनिमित्ततदाश्रयरूपस्तदधिकव्यावृत्त्यर्थं मात्रग्रहणमिति भावः ॥ द्रव्यमात्रापेक्षयाधिकव्यावृत्तौ घट इत्यादावपि न स्यादिति तात्पर्यम् ॥

(समाधानान्तरभाष्यम्)

इदं तर्हि—कुमारी वृक्षः कुण्डमिति ॥

(प्रदीपः) कुमारीति । विनापि स्त्रीत्वेन कुमारो देवदत्त इति कुमारशब्दस्य प्रयोगदर्शनात् स्त्रीत्वं न प्रातिपदिकार्थः ॥ वृक्षः कुण्डमिति । पुंनपुंसकोपलक्षणमेतत् । तटस्तटमित्येतत्तूदाहरणम् ॥ वृक्षकुण्डशब्दयोस्तु पुंनपुंसकत्वेन विना प्रयोगाभावात् लिङ्गस्य प्रातिपदिकार्थता ॥ कुण्डशब्दस्तु जीवति भर्तरि परेण जाते वर्तमानः पुल्लिङ्ग इति नपुंसकत्वेन विनापि तस्य प्रयोगात् कुण्डीति च स्त्रियामपि वर्तनात् कुण्डमित्येतदुदाहरणमित्यपरे ॥ जातिरेवात्र प्रातिपदिकार्थो न तु लिङ्गमित्यन्ये ब्रुवते ॥

(उद्द्योतः) न प्रातिपदिकार्थ इति । कुमारत्वस्यैव नियमेन भानात्तदर्थता न तु लिङ्गस्येति भावः । अत्र स्त्रीत्वं न प्रवृत्तिनिमित्तमिति भाव इति तत्त्वम् ॥ तटस्तटमिति । अस्य त्रिलिङ्गत्वेन प्रातिपदिकात्कस्यापि लिङ्गस्य नियमेनानुपस्थित्या तस्य प्रातिपदिकार्थत्वाभाव इति भावः ॥ जातिरेवात्रेति । अत्र प्रकृतसूत्रे ॥ जातिग्रहणं प्रवृत्तिनिमित्तपरम् । प्रातिपदिकार्थः प्रातिपदिकार्थशब्देन विवक्षितः । जातिपदमाश्रयस्याप्युपलक्षणम् । एवं च भाष्योक्तान्यप्युदाहरणानीति तद्भावः ॥ अन्तरङ्गत्वाच्च तयोरेव प्रातिपदिकार्थशब्देन ग्रहणम् । लिङ्गादीनां तु प्रायेण द्योतकसापेक्षप्रतीतिकत्वाद् बहिरङ्गत्वमिति तदाशयः ॥ एतदेवाभिप्रेत्य प्रातिपदिकार्थः सत्तेति वृत्तावुक्तम् ॥ उक्तव्याख्यास्माद्यं चिन्त्यमेव । अनेकलिङ्गत्वेपि स्वमोर्नपुंसकादिति शास्त्रबलेन लिङ्गे प्रातिपदिकवाच्यत्वस्यैव सर्वसम्मतत्वेन तटादिशब्देपि प्रातिपदिकार्थग्रहणेन सिद्धिः । अत एव द्वितीयाद्यन्ते लिङ्गबोधः । नहि समाने प्रातिपदिकवाच्यत्वे वृक्षादिशब्दवाच्यं प्रातिपदिकार्थशब्देन गृह्यते, न तटादिवाच्यमित्यत्र जातिरेवात्रेत्युक्तातिरिक्तं निमित्तमस्ति ॥ एवं चालिङ्गाव्ययानि लिङ्गप्रवृत्तिनिमित्तकाः शब्दाः प्रातिपदिकार्थ इत्यस्योदाहरणानि । अन्ये तु लिङ्गाधिक्यस्येति बोध्यम् ॥ येपि गौर्वाहीक इत्यादौ गोसदृशे लक्षणां वदन्ति, तेषां मते तदेव प्रवृत्तिनिमित्तम् । तदुत्तरत्वप्रत्ययेनाभिधीयमानत्वस्यैव प्रवृत्तिनिमित्तत्वस्य विवक्षितत्वात् । अस्माकं तु शक्यतावच्छेदकारोपेणैव तत्तद्बोधकपदे एव लक्षणेति वादिनां शङ्कैव न ॥

(परिमाणपदप्रयोजनाधिकरणम्)

(आक्षेपभाष्यम्)

अथ परिमाणग्रहणं किमर्थम्? ॥

(प्रदीपः) अथेति । द्रोणादयः परिमाण एव वर्तन्त इति प्रातिपदिकार्थग्रहणेनैव प्रथमा सिद्धेति प्रश्नः ॥

(उद्द्योतः) भाष्ये—अथ परिमाणेति । द्रोणादयो यदि परिमाणवचनास्तदा प्रातिपदिकार्थत्वात्सिद्धिरिति प्रश्नाशयः ॥

(समाधानभाष्यम्)

द्रोणः खारी आढकमित्यत्रापि यथा स्यात् ॥

(प्रदीपः) द्रोण इति । यदा मानमेयसंबन्धाद् व्रीह्यादौ द्रोणादयो वर्तन्ते तदा व्यभिचारान्नास्ति मेयस्य प्रातिपदिकार्थत्वम् ॥

(उद्द्योतः) उत्तरं तु लक्षणया परिमेयवृत्तिता यदा तदर्थमितीत्याह—यदा मानमेयेति ॥ व्यभिचारादिति । मेयस्यापि द्रोणत्वारोपेण द्रोणादिपदेभ्यो बोधे तद्बोधेपि परिमाणस्य भानात्स नियतः । परिमाणे वृत्तौ मेयार्थत्वाभावेन व्यभिचारी स इति भावः ॥ प्रातिपदिकेन नियतोपस्थितिविषयो हि प्रातिपदिकार्थः ॥ परिमाणशब्दे च कर्मणि ल्युट् परिमेये इत्यर्थं इति तात्पर्यार्थः ॥ एवं हि सिंहो माणवक इत्यादौ सा न स्यात् । सिंहसदृशार्थस्य व्यभिचारेणाप्रातिपदिकार्थत्वात् । तस्मात् द्रोणः खारी आढकमित्यत्रापि यथा स्यादिति भाष्यस्य विभक्त्यर्थस्य परिमाणस्य परिच्छेद्यपरिच्छेदकभावेन व्रीह्यादौ मेयेऽन्वयो यथा स्यादित्यर्थः ॥ प्रातिपदिकार्थे प्रथमायां तु नामार्थयोरभेदान्वयव्युत्पत्तिविरोधेन तथान्वयो न स्यात् कैयटादिमतेपि इत्यत्र मेयवृत्तित्वेपि यथा स्यादिति लक्षणया भाष्यव्याख्याया आवश्यकत्वाच्च । सूत्रभाष्यकृतोः सिंहो माणवक इत्यादेरज्ञानकल्पना चाधिका ॥ यदा यो नियतोपस्थितिकः स तदा प्रातिपदिकार्थ इति स्वीकृत्य तदकरणस्यैव न्याय्यत्वं च । मद्व्याख्यायां शाब्दबोधवैलक्षण्याय सूत्रे तद्ग-

हणम् । न च परिमाणं प्रातिपदिकार्थ इति तत एव तल्लाभात्तत्र प्रथमाविधानं व्यर्थं द्रोणत्वादिना तस्य तदर्थत्वेपि परिमाणत्वेन तदर्थत्वाभावात् । न च तव मते द्रोणो व्रीहिमानयेत्यपि स्यात् । प्रातिपदिकार्थसाहचर्यान्नाम्नोः सम्बन्धे समानविभक्तिकनामान्तरार्थेऽन्वये एव परिमाणे प्रथमायाः साधुत्वबोधनात् । अत एवाभिहिते प्रथमेत्यादिलक्षणैः समफलता । मन्मते हि सिंहो माणवक इति वत् द्रोणो व्रीहिरित्यपि लक्षणया साधु, शाब्दबोधकृतवैलक्षण्यानादरेणापि तत्र तत्र वार्त्तिकप्रवृत्तेर्दर्शनादिति नव्याः ॥

प्रवृत्तिनिमित्तं मुख्यं तदाश्रयश्चेति द्वावेव प्रातिपदिकार्थशब्देनात्र विवक्षितावत्यन्तरङ्गत्वात् । अतः परिमाणग्रहणं लक्ष्यार्थोपलक्षणमिति कैयटाशयमन्ये ॥

अपरे तु प्रातिपदिकग्रहणं किमर्थमित्यस्य ज्ञापकात् सिद्धिरित्याशयः ॥ तदजानान एकदेश्याह—उच्चैरित्यादि । एकदेश्युक्तित्वादेव तिङ्समानाधिकरणे प्रथमेति वार्त्तिकेन तद्भाष्येणैतत्सूत्रस्थेनाव्ययादाबिति सूत्रस्थेन ज्ञापकादव्ययेभ्यः सर्वा विभक्तय इत्यादि भाष्येण च न विरोधः । तस्मात्प्रातिपदिकग्रहणस्य फलान्तरं न कल्प्यमित्येव भाष्यतात्पर्यम् । एवं प्रत्याख्यातप्रायं प्रातिपदिकग्रहणम् ॥ ज्ञापकात्सर्वविभक्त्युत्पत्तौ प्रथमाया अपि सत्त्वेन च तत्प्रयुक्तकार्यसिद्धिः । तिङ्समानाधिकरणे प्रथमैवेति च नियमात्र वार्त्तिकमतेऽपि दोषः ॥ अथ लिङ्गेत्यादेर्वृक्षः कुण्डमितीत्यन्तस्य इत्यन्ये ब्रुवत इति मतेन कैयटोक्त एवार्थः । एवद्रीत्यैव च द्रोणादिशब्दे न सिध्यति । ते हि द्रोणत्वादिप्रवृत्तिनिमित्तका अपि द्रव्यनिष्ठलिङ्गमिव परिमाणत्वमपि बोधयन्तीत्यधिकार्था अतः परिमाणग्रहणम् । न च तेषां तन्निष्ठपरिमाणत्वबोधकत्वे प्रमाणाभावः । सूत्रभाष्यप्रामाण्येनानुभवादिना च तदङ्गीकारात् । तच्चोन्मानादीनामप्युपलक्षणम् । तद्ध्वनयन्नुदाहरति—द्रोणः खारी आढकमिति । अत्र कैयटव्याख्याने नव्यव्याख्याने च भाष्ये ऽन्वयिव्रीह्यादिपदानुपादानेन न्यूनता । नव्यव्याख्याने द्रोणो व्रीहिमानयेति प्रयोगापत्तिश्च । आनुमानिकसाधुत्वबोधकवचनकल्पने गौरवं च । प्रातिपदिकार्थलिङ्गसाहचर्येण परिमाणस्यापि प्रातिपदिकार्थत्वौचित्यं च । अतएव द्वन्द्वोपपत्तिः । कैयटव्याख्याने यद्वा यो नियतोपस्थितिक इत्याश्रित्य तदकरणापत्तिश्च । जातितदाश्रययोरेव प्रातिपदिकार्थपदेन ग्रहणेन मेयपरत्वेपि सिद्धिश्च । किं च—यत्रैतानि समुदितानि भवन्ति तत्रैव स्यादित्यनुपदवक्ष्यमाणभाष्यविरोधः । तस्य हि यत्र स्वादिविध्युद्देश्ये एतानि समुदितानि वाच्यत्वेन भवन्ति तत्रैव स्यादित्यर्थोऽक्षरस्वारस्येन लभ्यते । पदस्यैव लक्षणेति सिद्धान्ते द्रोणो व्रीहिरित्यस्य कैयटरीत्यानुदाहरणत्वाच्च । न च द्रोणादिशब्दानामियत्ताविशेषावच्छिन्नपलादिपरिमितव्रीह्यादिपरिच्छेदकद्रोणत्ववदादिबोधजनकत्वात्परिच्छेदकत्वस्यापि प्रातिपदिकत एव लाभात्तत्र प्रथमाविधानवैयर्थ्यमिति वाच्यम् । लाघवेन तत्समानाधिकरणद्रोणत्वादेरखण्डोपाधिरूपस्य जातिरूपस्यैव वा प्रवृत्तिनिमित्तत्वात् ॥ तत्तु भासमानमपि लिङ्गवद्विशेष्यान्वय्येव । द्रोणः परिमाणमिति तु द्रोणादिशब्दानामनेकार्थत्वान्निर्णयाय, द्वौ ब्राह्मणावितिवद्बेति वदन्ति ॥

(वचनपदप्रयोजनाधिकरणम्)

(आक्षेपभाष्यम्)

अथ वचनग्रहणं किमर्थम् ?॥

(प्रदीपः) **अथ वचनग्रहणमिति** । अर्थे कार्यासंभवात् प्रातिपदिकार्थादिवचनात् प्रथमा भविष्यतीति प्रश्नः ॥

(उद्द्योतः) ननु शब्दे कार्यसिद्ध्यर्थं वचनग्रहणमत आह—**अर्थे इति** ॥ **प्रातिपदिकार्थादिवचनादिति** । सूत्रे तु प्रकृतेरधिकरणत्वविवक्षायां सप्तमीति भावः ॥

(समाधानभाष्यम्)

इह समुदाये वाक्यपरिसमाप्तिर्दृश्यते—गर्गाः शतं दण्ड्यन्तामिति । अर्थिनश्च राजानो हिरण्येन भवन्ति, न च प्रत्येकं दण्डयन्ति । सत्येतस्मिन् दृष्टान्ते यत्रैतानि सर्वाणि समुदितानि भवन्ति तत्रैव स्यात्—द्रोणः खारी आढकमिति । इह न स्यात्—कुमारी वृक्षः कुण्डमिति ॥

(प्रदीपः) **इहेति** । प्रथमा विधीयमानत्वात् प्रधानम् । न च गुणभेदे प्रधानस्य भेदो भवतीति यत्रैतत् त्रयं समुदितं तत्रैव प्रथमा स्यात् । वचनग्रहणे तु प्रत्येकं संबध्यमाने वाक्यत्रयं संपद्यत इति न दोषो भवति ॥

(उद्द्योतः) गर्गाः शतमित्यत्र शतस्य प्राधान्यात्तदावृत्तेरनुचितत्वेनास्तु समुदाये वाक्यपरिसमाप्तिः प्रकृते कथमत आह—**प्रथमेति** ॥

(समाधानबाधकभाष्यम्)

नैतदस्ति प्रयोजनम् । प्रत्येकमपि वाक्यपरिसमाप्तिर्दृश्यते । तद्यथा—गुणवृद्धिसंज्ञे प्रत्येकं भवतः ॥

(प्रदीपः) **प्रत्येकमिति** । प्रथमा सिद्धैव, केवलं नियमाय तदनुवादेन प्रातिपदिकार्थादिभिस्तस्याः संबन्धो विधीयते, स च संबन्धिभेदाद्भिन्नः ॥

अथ वा न्यायद्वयसंभवे लक्ष्यदर्शनवशात् **प्रत्येकं वाक्यपरिसमाप्तिरिति** पक्ष इहाश्रयिष्यते इति भावः ॥

(उद्द्योतः) **प्रथमा सिद्धैवेति** । तथा चाविधीयमानत्वादप्राधान्यात्सिद्धा पूर्वन्यायानवतार इति भावः ॥ **नियमायेति** । कर्मण्येव द्वितीयेत्यादिनियमेऽनियतकर्मादिषु प्राप्तप्रथमावारणाय प्रातिपदिकार्थमात्रेणातत्संबन्धनमित्यर्थः ॥

ननु प्राधान्याप्राधान्ये निर्णेतुमशक्ये विधीयमानस्योद्देश्यार्थत्वादुद्देश्येऽपि प्राधान्यस्य वक्तुं शक्यत्वात् । अत एव यागोद्देशेन विधीयमाना अपि व्रीह्यादयो गुणत्वेन व्यवतिष्ठन्तेऽत आह—**अथवेति** ॥

(समाधानान्तरभाष्यम्)

इदं तर्हि प्रयोजनम्—उक्तेष्वप्येकत्वादिषु प्रथमा यथा स्यात्—एको द्वौ बहवः ॥

(प्रदीपः) **उक्तेष्वपीति** । अनभिहिताधिकाराद् **बहुषु बहुवचनमि**त्यादिनास्य प्रकरणस्यैकवाक्यत्वात् परिगणनस्य च प्रत्याख्यातत्वादेकादिभिः शब्दैरेकत्वादीनामभिहितत्वादनभिहिताधिकारस्य प्रत्याख्यान उक्तार्थत्वाद्वा प्रथमा न स्यात् । वचनग्रहणात् तु भवति ॥ वचनग्रहणस्य पूर्वाचार्यप्रसिद्ध्याश्रयेण संख्यावाचित्वात्तेनाभिहिते वचने प्रथमा भवतीत्यर्थः संपद्यते ॥

(उद्द्योतः) नन्वनभिहिताधिकारेऽपि संख्याविधेस्तन्मध्यपतितत्वाभावोऽत आह—**बहुष्विति** । इहाधिकृतेनानभिहित इत्यनेन प्रातिपदिकार्थादेः सर्वस्य प्रातिपदिकेनाभिहिततया संख्यैव विशेष्यत इति भावः ॥ ननु परिगणनान्न दोष इत्यत आह—**परिगणनस्य चेति** ॥ **वचनग्रहणादिति** । एवं चात्र सूत्रेऽनभिहित इत्यस्यासंबन्ध एवेति भावः ॥

(मात्रग्रहणप्रयोजनाधिकरणम्)

(आक्षेपभाष्यम्)

अथ मात्रग्रहणं किमर्थम् ? ॥

(समाधानभाष्यम्)

एतन्मात्र एव प्रथमा यथा स्यात् । कर्मादिविशिष्टे मा भूत्—कटं करोति ॥

(प्रदीपः) **कर्मादिविशिष्ट इति** । कर्मण्येव द्वितीयेति प्रत्ययनियमे कर्मादीनामनियमात्तेषु प्रथमा स्यात् । मात्रग्रहणात्त्ववधारणार्थात्र भवति । तेन प्रातिपदिकार्थमात्र एव प्रथमा भवति न त्वधिककर्मादिसद्भावे ॥

(उद्द्योतः) **मात्रग्रहणादिति** । मात्रग्रहणं कुर्वतः सूत्रकृतः प्रत्ययनियम एवाभिप्रेतः । न च प्रत्ययनियमेपि प्रातिपदिकार्थ एवेति नियमेन कर्मादिषु तद्वारणसंभवात्तद्वैयर्थ्यमिति वाच्यम् । यथा कर्मण्येव द्वितीयेति नियमेन कर्मत्वाभावसमानाधिकरणार्थान्तरस्यैव व्यावृत्तिर्न तु तत्समानाधिकरणार्थान्तरस्य । अत एव गां दोग्धि पय इत्यादावपादानत्वादिशक्तियोगेऽपि द्वितीया भवति । एवं च 'कर्मणि सत्येव द्वितीया न तु तदसत्त्वे' इत्येवं नियमाकारः । तथा 'प्रातिपदिकार्थसत्त्वे एव प्रथमा, न तु तदसत्त्वे' इति नियमेन निरर्थकस्यैव व्यावृत्तिर्न तु प्रातिपदिकार्थसत्त्वे एव कर्मत्वादेरिति मात्रग्रहणस्यावश्यकत्वात् । न चैवं संख्याधिक्येऽपि प्रथमा न स्यात् । द्व्येकयोरित्यादिभिरस्यैकवाक्यतया तदाधिक्ये प्रवृत्तेः ॥

(समाधानबाधकभाष्यम्)

नैतदस्ति प्रयोजनम् । कर्मादिषु द्वितीयाद्या विभक्तयः । ताः कर्मादिविशिष्टे बाधिका भविष्यन्ति ॥

(प्रदीपः) **द्वितीयाद्या इति** । कर्मणि द्वितीयैवेत्यर्थनियम आश्रयिष्यत इति भावः ॥

(उद्द्योतः) **अर्थनियम इति** । अत्र पक्षे तु तुल्यन्यायात्सम्बोधने चेति सूत्रं लिङ्गादिग्रहणमनभिहित इति सूत्रे समर्थाद्वेति पक्षेण वचनग्रहणं च प्रत्याख्यातमेवेति दिक् ॥

(समाधानबाधकान्तरभाष्यम्)

अथ वाचार्यप्रवृत्तिर्ज्ञापयति—न कर्मादिविशिष्टे प्रथमा भवतीति । यदयं संबोधने प्रथमां शास्ति ॥

(प्रदीपः) **अथवेति** । प्रत्ययनियमपक्षेपि दोषाभाव इत्यर्थः ॥ **यदयमिति** । यदि प्रातिपदिकार्थसद्भावमात्राश्रयेणाधिकार्थसद्भावेपि प्रथमा स्यात्तदा संबोधनाधिक्ये प्रथमायाः सिद्धत्वात् पुनर्विधानमनर्थकं स्यात् ॥

(समाधानसाधकज्ञापकनिरसनभाष्यम्)

नैतदस्ति ज्ञापकम् । अस्त्यन्यदेतस्य वचने प्रयोजनम् ॥ किम् ? । "सामन्त्रितम्" इति वक्ष्यामीति ॥

(समाधानबाधकज्ञापकान्तरभाष्यम्)

यत्तर्हि योगविभागं करोति ॥ इतरथा हि "संबोधने आमन्त्रितम्" इत्येव ब्रूयात् ॥

(समाधानान्तरभाष्यम्)

इदं तर्हि—उक्तेष्वप्येकत्वादिषु प्रथमा यथा स्यात्—एको द्वौ बहव इति ॥

(प्रदीपः) **उक्तेष्वपीति** । मात्रशब्दः सामान्यवचन आश्रीयते । यथा ब्राह्मणमात्रं पूजयतीति । एवं प्रातिपदिकार्थमात्रेऽभिहितेपि एकत्वादौ प्रथमा भवति ॥ अन्ये त्वाहुः—मीयते अनयेति मात्रा संख्योच्यते । समाहारद्वन्द्वे नपुंसकत्वाच्च ह्रस्वत्वं कृतम् । तेनाभिहितायामपि संख्यायां प्रथमा भवति ॥

(अन्यतरप्रत्याख्यानभाष्यम्)

वचनग्रहणस्याप्येतत्प्रयोजनमुक्तम् । अन्यतरच्छक्यमवक्तुम् ॥

(सामानाधिकरण्ये प्रथमासाधनाधिकरणम्)

(१५२१ आक्षेपवार्तिकम् ॥ १)

॥ * ॥ प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमालक्षणे पदसामानाधिकरण्ये उपसंख्यानमधिकत्वात् ॥ * ॥

(भाष्यम्) प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमालक्षणे पदसामानाधिकरण्ये उपसंख्यानं कर्तव्यम् । वीरः पुरुष इति ॥

किं पुनः कारणं न सिध्यति ? । अधिकत्वात् ।

व्यतिरिक्तः प्रातिपदिकार्थे इति कृत्वा प्रथमा न प्राप्नोति ॥

कथं व्यतिरिक्तः ?। पुरुषे वीरत्वम् ॥

(प्रदीपः) प्रातिपदिकार्थेति । अवधारणार्थान्मात्रग्रहणात् संबोधने चेति ज्ञापकाद्वाधिकार्थप्रतीतौ प्रथमया न भाव्यम्। अस्ति च वीरः पुरुष इत्यादौ सामानाधिकरण्याद्विशेषणविशेष्यभावस्याधिकस्य प्रतीतिः। न च समासविधानं प्रथमोत्पत्तिलिङ्गम्, द्वितीयाद्यन्तानामपि वीरं पुरुषमानयेत्यादौ समाससद्भावात् ॥

(उद्द्योतः) सामानाधिकरण्यादिति । तयोः पदयोरेकार्थवृत्तित्वात्तत्प्रवृत्तिनिमित्तयोरेकवृत्तित्वाच्चेत्यर्थः ॥ विशेषणविशेष्यभावस्य विशेषणत्वविशेष्यत्वरूपस्य ॥ भाष्ये—व्यतिरिक्तः प्रातिपदिकार्थे इति । अतिरिक्तार्थेन विशिष्ट इत्यर्थः। मयूरव्यंसकादित्वात्समासः ॥ भाष्ये—वीरत्वमिति । वीरशब्दादर्शआद्यजन्तात्त्वः। वीरवत्त्वं वीरसम्बन्धस्तन्निरूपितविशेष्यतेति यावत्। यतो वीरत्वं वीरनिरूपितविशेष्यत्वं पुरुषेऽधिकं भासतेऽतः पुरुषार्थोऽधिकार्थविशिष्ट इत्यर्थः ॥ एवं वीरे पुरुषनिरूपितं विशेषणत्वमधिकमिति बोध्यम्। तथा वीरत्वं पुरुषे इत्युक्त्या स्ववृत्तिवीरत्वपुरुषत्वयोः साहित्यरूपो वीरपुरुषयोर्विशेषणत्वविशेष्यत्वनियामकः संबन्ध उक्तः सोपि वाक्यार्थ एव ॥ तदेवाभिप्रेत्य कर्मधारयविषये द्वन्द्वापादनं चार्थे द्वन्द्व इति सूत्रे भाष्ये कृतम्। एवं च वीरत्वपुरुषत्वसमूहवान् वीरपुरुष इति बोधः ॥

(१५२२ समाधानवार्तिकम् ॥ २)

॥ * ॥ न वा वाक्यार्थत्वात् ॥ * ॥

(भाष्यम्) न वा वक्तव्यम् ॥ किं कारणम् ?। वाक्यार्थत्वात्। यदत्राधिक्यं वाक्यार्थः सः ॥

(प्रदीपः) न वेति । वीरप्रातिपदिकादनपेक्षितशब्दान्तरार्थसंसर्गोपहितविशेषणभावात् स्वार्थमात्रनिष्ठात् प्रथमा विधीयते। एवं पुरुषशब्दादपि। पश्चात्त्वाकाङ्क्षादिवशाद्विशेषणविशेष्यभावावगतिरुपजायमाना बहिरङ्गत्वादन्तरङ्गं संस्कारं पूर्वप्रवृत्तं बाधितुं नोत्सहते ॥

(उद्द्योतः) अनपेक्षितशब्दान्तरेति । अनपेक्षितशब्दान्तरार्थसंसर्गेणोपहितः प्रापितो विशेषणभावः स्वार्थे येन तस्मादित्यर्थः। पुरुषसंसर्गेण हि वीरार्थस्य तन्निरूपितविशेषणतेति भावः ॥ एवमिति । पुरुषशब्दार्थस्य तदर्थसंसर्गेण तन्निरूपितविशेष्यतेत्यर्थः। मात्रपदेनान्तरङ्गार्थकृतमेवाधिक्यं व्यावर्त्यते न तु बहिरङ्गकृतमिति भावः ॥ भाष्ये—आधिक्यमिति । स्वार्थे ष्यञ् ॥ वाक्यार्थः वाक्यशक्यः ॥ विषयतानामपि शक्यत्वं मञ्जूषायामुपपादितम् ॥

(समाधानाय न्यासान्तरम्)

अथ वा "अभिहिते प्रथमा" इत्येतल्लक्षणं करिष्यते ॥

(प्रदीपः) अभिहित इति। तिङ्कृत्तद्धितसमासैरभिहिते कर्त्रादौ प्रथमेत्यर्थः। ततश्च वीरः पुरुष इत्यत्रार्थाधिक्येप्यभिहितत्वमात्राश्रयां प्रथमा भविष्यति ॥

(उद्द्योतः) ननु विभक्त्यन्तरान्वितेऽपि सुन्दरं कटमित्यादौ प्रथमा स्यादत आह—तिङ्कृदिति। अभिहिते इत्यत्र चार्थनियम एवाश्रीयत इति उच्चैरित्यादौ न दोषः ॥

(१५२३ न्यासान्तरदूषकवार्तिकम् ॥ ३)

॥ * ॥ अभिहितलक्षणायामनभिहिते प्रथमाविधिः ॥ * ॥

(भाष्यम्) अभिहितलक्षणायामनभिहिते प्रथमा विधेया। वृक्षः प्लक्ष इति ॥

(दूषणपरिहारभाष्यम्)

उक्तं वा *। किमुक्तम् ?। अस्तिर्भवन्तीपरः प्रथमपुरुषोऽप्रयुज्यमानोप्यस्तीति गम्यते। वृक्षः प्लक्षः 'अस्ति' इति गम्यत इति ॥

(१५२४ दूषणान्तरवार्तिकम् ॥ ४)

॥ * ॥ अभिहितानभिहिते प्रथमाभावः ॥ * ॥

(भाष्यम्) अभिहितानभिहिते प्रथमा प्राप्नोति। क्व?। प्रासादे आस्ते शयन आस्त इति। सद्प्रत्ययेनाभिहितमधिकरणमिति कृत्वा प्रथमा प्राप्नोति ॥

(प्रदीपः) अतिव्याप्तिमुद्भावयितुमाह—अभिहितानभिहित इति। प्रासाद आस्त इति। सदिक्रियास्थिक्रियाद्वयसाधनाधिकरणशक्तिद्वयसद्भावादेकस्याः शक्तेरभिहितत्वात्तदाश्रया प्रथमा प्राप्नोतीत्यर्थः ॥

(उद्द्योतः) प्रथमा प्राप्नोतीति। परत्वादितिभावः। न च शक्तिर्गुणाश्रया तत्र प्रधानमनुरुध्यत इति न्यायेनायं दोषो वारयितुं शक्य इति वाच्यम्। क्रिययोरत्र गुणप्रधानभावाभावादित्याहुः ॥

(दूषणपरिहाराय न्यासान्तरम्)

एवं तर्हि "तिङ्समानाधिकरणे प्रथमा" इत्येतल्लक्षणं करिष्यते ॥

(प्रदीपः) एवं तर्हीति। यथा देवदत्तः पचतीति। प्रासादे आस्त इत्यादौ तु वैयधिकरण्यात्प्रथमाया अभावः ॥

(उद्द्योतः) भाष्ये—तिङ्समानाधिकरण इति। न चोच्चैरित्यादौ प्रथमानापत्तिः, तिङ्समानाधिकरणे प्रथमैवेत्यर्थनियममात्राश्रयणेनादोषात् ॥

(१५२५ न्यासान्तरदूषणवार्तिकम् ॥ ५)

॥ * ॥ तिङ्समानाधिकरण इति चेत्तिङोऽप्रयोगे प्रथमाविधिः ॥ * ॥

(भाष्यम्) तिङ्समानाधिकरण इति चेत्तिङोऽप्रयोगे प्रथमा विधेया। वृक्षः प्लक्षः ॥

(प्रदीपः) **तिङोप्रयोग इति** । न हि तिङन्तपदप्रयोगमन्तरेण तत्सामानाधिकरण्यसद्भावः ॥

(दूषणपरिहारभाष्यम्)

उक्तं पूर्वेण * । किमुक्तम् ? । अस्तिर्भवन्तीपरः प्रथमपुरुषोप्रयुज्यमानोप्यस्तीति गम्यते । वृक्षः प्लक्षः 'अस्ति' इति गम्यत इति ॥

(प्रदीपः) **उक्तं पूर्वेणेति** । आक्षिप्तक्रियापदापेक्षं सामानाधिकारण्यमस्ति ॥

(उद्द्योतः) **उक्तं पूर्वेणेति** । पूर्वग्रन्थेनेत्यर्थः । पूर्वेणाचार्येणेति कश्चित् ॥ अनेनानभिहितसूत्रोक्तं विप्रतिषेधाद्वेति वार्तिकं प्रौढ्येति सूचितम् ॥

(१५२६ तिङ्साधनाधिकरण आक्षेपवार्तिकम् ॥ ६)

॥ * ॥ शतृशानचोश्च निमित्तभावात्तिङोभावस्तयोरपवादत्वात् ॥ * ॥

(भाष्यम्) **शतृशानचोश्च निमित्तभावात्तिङोभावः ॥ क्व ? । पचत्योदनं देवदत्त इति ॥ किं कारणम् ? । तयोरपवादत्वात् । शतृशानचौ तिङपवादौ । तावत्र बाधकौ । न चापवादविषये उत्सर्गोभिनिविशते । 'पूर्वं ह्यपवादा अभिनिविशन्ते पश्चादुत्सर्गाः' । 'प्रकल्प्य चापवादविषयमुत्सर्गोभिनिविशते' । न तावदत्र कदाचित्तिङादेशो भवति । अपवादौ तावच्छतृशानचौ प्रतीक्षते ॥**

(प्रदीपः) **शतृशानचोश्चेति** । देवदत्त पच् ल् इति स्थिते यावत्तिङ उत्पत्तिर्नास्ति तावत्तिङ्सामानाधिकरण्याभावात् 'प्रथमेव' इति नियमाभावाद्देवदत्तशब्दादविशेषविहिताः सर्वे स्वादयः स्थिता इति लटः स्थाने द्वितीयाद्यन्तपदसामानाधिकरण्ये विधीयमानौ शतृशानचौ प्राप्नुतो न तु तिङः । तेषां तु लङादिरवकाशस्तद्विषय एव च प्रथमाया अपि । 'कर्मणि द्वितीयैव' इत्यर्थनियमे द्वितीयादीनामत्र सद्भाव इति मन्यते । निमित्तमत्र शतृशानचोरप्रथमासामानाधिकरण्यम् ॥ **पूर्वं ह्यपवादा इति** । इह दर्शनद्वयम् । सर्वविशेषस्वीकारेण वोत्सर्गस्य प्रवृत्तिः, कतिपयविशेषावगाहनेन वा । तत्र पूर्वस्मिन् दर्शने—उत्सर्गस्य विषयविभागाय पूर्वमपवादः प्रवर्तते, पश्चात्तद्विमुक्ते विषय उत्सर्गः । द्वितीये तु दर्शने—अपवादविषयं प्रकल्प्योत्सर्गः प्रवर्तते ॥

(उद्द्योतः) तिङ्समानाधिकरणे प्रथमाया अप्रथमासमानाधिकरणे शतृशानचोर्विधानस्य च वाक्यसंस्कारे एव प्रवृत्तिरित्याह—**देवदत्तेति** ॥ ननु एकवाक्यतया विधानमिति पक्षे तिङ्समानाधिकरण्याभावात् प्रथमाया इव कर्माद्यभावाद् द्वितीयादीनामप्यभावेन द्वितीयादिसामानाधिकरण्ये विधीयमानशत्रादेरप्राप्तौ तिङ्क्षु जातेषु प्रथमा भविष्यतीत्यत आह—**यावत्तिङ इति** । भिन्नवाक्यतयाऽविशेषेणोत्पन्नानामर्थनियम इति भावः ॥ **सर्वे स्वादय स्थिता इति** । विनिगमनाविरहेण सर्वेऽपि समूहालम्बनबुद्धिविषयतया स्थिता इत्यर्थः ॥ **द्वितीयाद्यन्तेति** । **अप्रथमेति** पर्युदासेन प्रथमाभिन्नविभक्त्यन्तसमानाधिकरणे इत्यर्थकेन शत्रादेर्विधानमिति भावः ॥ नन्वेवमपि कर्मण्येव द्वितीयेत्यादिनियमात्कथं द्वितीयादीनां स्थितिरत आह—**कर्मणीति** । वार्तिककारस्यार्थनियम एव सम्मत इति भावः ॥ नन्वपवादेनोत्सर्गस्य बाधाविशेषात्तद्द्वयोपन्यासः किमर्थोऽत आह—**इहेति** । उत्सर्गशास्त्रप्रवृत्तिबाधप्रकारविषयमिति भावः ॥ **द्वयमिति** । लक्षणैकचक्षुष्कदर्शनं लक्ष्यैकचक्षुष्कदर्शनं चेत्यर्थः ॥ तदेवाह—**सर्वविषयस्वीकारेणेति** । सत्येवं मन्यते शास्त्रेण सर्वत्र प्राप्तस्य विषयविशेषेऽपवादेन निवृत्तिरिति ॥ **कतिपयेति** लक्ष्यैकचक्षुष्को हि लक्ष्यदर्शनात्प्रागेवोत्सर्गस्यापवादविषयातिरिक्तं विषयं निर्णयति ॥ **विषयविभागायेति** । किंविषये निश्चिता प्रवृत्तिः किंविषये बाधकबाध्येति विषयविभागायेत्यर्थः ॥ **पूर्वं ह्यपवादा इति** । अपवादशास्त्राणीत्यर्थः । **अभिनिविशन्त** इत्यस्य बुद्धिविषया भवन्तीत्यर्थः । ततस्तद्विषयत्वाभावेन निर्णीते विषये उत्सर्गो बुद्धिविषयः सन् लक्ष्यं संस्करोतीति भावः । द्वितीये त्वपवादशास्त्रविषयं स्वयमेव त्यक्त्वोत्सर्गशास्त्रेण तद्विषयभिन्नं लक्ष्यं संस्करोति । शास्त्रप्रक्रियाज्ञानपूर्वकप्रयोगे एव धर्म इत्यस्मादेव ज्ञायते इति बोध्यम् ॥ भाष्ये—**प्रतीक्षत इति** । अपवादविषयत्वं ज्ञात्वा तत्र तिङ्बुद्धिर्निवर्तत इत्यर्थः ॥

(समाधानभाष्यम्)

पाक्षिक एष दोषः । कतरस्मिन्पक्षे शतृशानचोर्द्वैतं भवति—अप्रथमा वा विधिनाश्रीयते प्रथमा वा प्रतिषेधेनेति ? ॥ विभक्तिनियमे चापि द्वैतं भवति—विभक्तिनियमो वा स्यादर्थनियमो वेति ॥ तद्यदा तावदर्थनियमः अप्रथमा च विधिनाश्रीयते, तदा एष दोषो भवति ॥ यदा हि विभक्तिनियमः, तदा यद्येवमप्रथमा विधिनाश्रीयते, अथापि प्रथमा प्रतिषेधेन, तदा न दोषो भवति ॥ प्रातिपदिकार्थ० ॥ ४६ ॥

(प्रदीपः) एवं पर्युदासार्थनियमपक्षाश्रयेण चोदितं प्रसज्यप्रतिषेधाश्रयेण त्वर्थनियमे पक्षद्वयेऽपि प्रत्ययनियमपक्षाश्रयेण परिहर्तुमाह—**पाक्षिक इति** ॥ **अप्रथमा वा विधिनेति** । अप्रथमेति पर्युदासेन द्वितीयादीनां यदा ग्रहणमित्यर्थः ॥ **प्रथमा वेति** । प्रसज्यप्रतिषेध आश्रीयते इत्यर्थः ॥ **तद्यदेति** । कर्मणि द्वितीयैवेत्यस्मिन्नियमे द्वितीयादीनामनियमात्प्रातिपदिकार्थमात्रेऽपि भावात्तदाश्रयौ शतृशानचौ प्राप्नुत इति दोषः । प्रसज्यप्रतिषेधे तु प्रथमाया अपि तत्र भावात्तदाश्रयप्रतिषेधः प्रवर्तत इत्यर्थनियमपक्षेऽपि न दोषः । शतृशानचोरभावात्तिङ्क्षु सत्सु तत्सामानाधिकरण्यात्प्रथमैवेति नियमेन द्वितीयादीनां व्यावर्तनात् ॥ **यदा**

हीति । कर्मण्येव द्वितीयेत्येवं द्वितीयादीनां कर्मादिषु नियतत्वात्तदभावे तासामत्राभावादनियतायाश्च प्रथमायाः संनिधानात्पर्युदासे प्रसज्यप्रतिषेधे वा नास्ति शतृशानचोरत्र प्रसङ्ग इत्यर्थः ॥ ४६ ॥

(उद्द्योतः) **पाक्षिक इति** । पक्षे भव इत्यर्थेऽध्यात्मादित्वाट्ठञ् ॥ **कतरस्मिन्पक्षे** इति भाष्ये स दोष इति शेषः ॥ **विभक्तिनियमे चापीति** । अर्थनियमोऽपि सामान्यरूपेण विभक्तिविषयो नियमो भवत्येव नियमस्यानेकाश्रितत्वादिति भावः । विभक्तेरर्थान्तरसम्बन्धनिवर्तको **विभक्तिनियमः** । अर्थस्य विभक्त्यन्तरसम्बन्धनिवर्तको**ऽर्थनियम** इति भेदः ॥ तत्र पक्षचतुष्टयम्—पर्युदासार्थनियमो पर्युदासविभक्तिनियमो, प्रसज्यप्रतिषेधार्थनियमो, प्रसज्यप्रतिषेधविभक्तिनियमो चेति । तत्राद्ये एव दोषोद्भावनमिति भावः ॥ **पक्षद्वयेऽपि** पर्युदासप्रसज्यप्रतिषेधरूपपक्षद्वयेऽपि ॥ **प्रसज्यप्रतिषेधे त्विति** । यदि प्रथमासमानाधिकरणभिन्ने इति पर्युदास आश्रीयते तदाऽपि न दोषः । अन्यसामानाधिकरण्यं प्रथमासामानाधिकरण्यस्यापि सत्त्वेन तत्त्वावच्छिन्नप्रतियोगिताकभेदाभावादित्यपि बोध्यम् ॥ नन्वर्थनियमे शतृशानचोरभावेऽपि सर्वत्र विभक्तिश्रवणापत्तिरत आह—**शतृशानचोरिति** ॥ **अनियतायाश्चेति** ॥ यदा हि विभक्तीत्यस्य भाष्यस्य यथास्थितसूत्रन्यासे इत्यर्थः । प्रत्ययनियमस्यैव सूत्रसम्मतत्वात् तत्र च प्रथमाया विशेषपुरस्कारेणानियतायाः प्रातिपदिकार्थमात्रप्रतिबद्धायाः संनिधानमस्त्येवेति भावः ॥ ननु वार्तिकन्यासेऽयं ग्रन्थः । तन्न्यासे एतन्नियमस्वीकारे प्रथमावाक्येऽप्येवमेव नियमापत्तौ देवदत्त पच इत्यवस्थायां विभक्तिसामान्याभावेन पर्युदासपक्षे प्रथमाभिन्नविभक्त्यन्तत्वाभावेन शत्रादेरप्राप्तावपि प्रसज्यप्रतिषेधे प्रथमान्तसामानाधिकरण्याभावेन निषेधाप्रवृत्तौ तौ स्यातामिति चेन्न । वार्तिकमते शत्रादिविधौ प्रसज्यप्रतिषेध एव प्रथमाविधावर्थनियम एवेति न दोषः । सूत्रमते तूभयथापि न क्षतिरिति तात्पर्यात् ॥ ४६ ॥

(अथ षष्ठीप्रकरणम्)

(१२४ शेषषष्ठीसूत्रम् ॥ २ । ३ । ३ आ. २ सू.)

५०८ षष्ठी शेषे ॥ २ । ३ । ५० ॥

(शेषशब्दार्थनिरूपणाधिकरणम्)

(आक्षेपभाष्यम्)

शेष इत्युच्यते । कः शेषः ? ॥

(प्रदीपः) **षष्ठी शेषे ॥ ५० ॥ कः शेष इति** । किमप्रधानं शेषः, उतोपयुक्तादन्यः । पूर्वस्मिन्पक्षे सर्वेषां कारकाणां क्रियार्थत्वाच्छेषत्वमिति तत्रापि षष्ठीप्रसङ्गः । सर्वत्र कर्मादीनां सद्भावादुत्तरोऽपि शेषार्थो न प्रकल्पत इति प्रश्नः ॥

(उद्द्योतः) **षष्ठी शेषे ॥ ५० ॥ किमप्रधानमिति** । शिष्लृ विशेषण इत्यतो घञि शिष असर्वोपयोग इत्यतो वा घञि निष्पन्न इत्यर्थः ॥ **तत्रापि षष्ठीप्रसङ्ग इति** । न चैतस्य कर्मत्वाद्यविवक्षायां चारितार्थ्येन क्रियाकारकभावेनान्वये तत्तद्विधिभिर्बाधात्क षष्ठ्यापत्तिः । अभिहितविषयेऽपि प्रथमया बाधादिति वाच्यम् । **ज्ञो विदर्थस्य करणे** इत्यादिषु शेष इत्यनुवृत्तेस्तद्विषये क्रियाकारकभावेनान्वयेऽपि परत्वात्षष्ठीप्रसङ्ग इति तदर्थात्त दोषः ॥

(समाधानभाष्यम्)

कर्मादिभ्यो येऽन्येऽर्थाः स शेषः ॥

(प्रदीपः) **कर्मादिभ्य इति** । कर्माद्यनन्तरं शेषशब्द उच्चार्यमाणस्तेभ्योऽन्यमर्थं प्रतिपादयति ॥ **येऽन्येऽर्था इति** । स्वस्वामिभावादयः संबन्धा इत्यर्थः । तदुक्तम्—

संबन्धः कारकेभ्योऽन्यः क्रियाकारकपूर्वकः ।
श्रुतायामश्रुतायां वा क्रियायां सोऽभिधीयते ॥

इति ॥ तत्राश्रुतायां क्रियायां राज्ञः पुरुष इत्यादौ क्रियाकारकसंबन्धपूर्वकोऽन्य एव स्वस्वामिभावादिकः संबन्धः प्रतीयते । मातुः स्मरतीत्यादौ तु श्रूयमाणे क्रियाशब्दे सदपि कर्मत्वमविवक्षित्वा विशेषणभाव एव स्मरणं प्रति मातुः प्रतिपाद्यते—मातृसंबन्धि स्मरणमिति ॥

(उद्द्योतः) शेषशब्दोऽन्यवाची तस्य प्रतियोग्याकाङ्क्षायामुपस्थितकर्मादय एव प्रकरणाद् गृह्यन्त इत्याह—**कर्माद्यनन्तरमिति** ॥ ननु कर्मादिव्यतिरिक्तार्थासंभव इत्यत आह—**स्वस्वामीति** ॥ **क्रियाकारकेति** । स्वत्वहेतुदानादिक्रियाकारकत्वपूर्वक इत्यर्थः । यत एवं विधोऽतः कारकेभ्योऽन्य इत्यर्थः ॥ **विशेषणभाव एव स्मरणं प्रति मातुरिति** । क्रियाकर्मत्वमूलकविशेष्यविशेषणभाव इत्यर्थः । एतेन क्रियाकारकभाव एव संबन्धत्वेन विवक्षित इत्यन्याय्यं षष्ठ्यर्थेन सांसर्गिकस्यैव विषयता । वक्ष्यति च भाष्यकारः—**राज्ञः पुरुष इत्यत्र राजा विशेषणं पुरुषो विशेष्य** इति ॥

(आक्षेपभाष्यम्)

यद्येवं शेषो न प्रकल्पते । न हि कर्मादिभ्योऽन्येऽर्थाः सन्ति ॥ इह तावद्—'राज्ञः पुरुषः' इति राजा कर्ता, पुरुषः संप्रदानम् । 'वृक्षस्य शाखा' इति वृक्षः शाखाया अधिकरणम् । तथा यदेतत्स्वं नाम चतुर्भिरेतत्प्रकारैर्भवति—क्रयणाद्, अपहरणाद्, याच्ञायाः, विनिमयादिति । अत्र च सर्वत्र कर्मादयः सन्ति ॥

(प्रदीपः) **अविदिताभिप्रायः पर आह—यद्येवमिति** । क्रियामन्तरेण संबन्धाभावात्सर्वत्र तस्या अवश्यं भावात्तन्निमित्तस्य च कर्मादेरिति भावः ॥ **राजा कर्तेति** । राजा पुरुषाय ददातीत्यर्थसंप्रत्ययात् ॥ **वृक्ष इति** । लोकप्रसिद्ध्यैतदुक्तम् । वैशेषिकप्रक्रियया त्ववयवोऽवयविनोऽधिकरणम् ॥ **विनिमयादिति** । परिवर्तनादित्यर्थः ॥

(उद्द्योतः) **संबन्धाभावादिति** । दानादिना स्वीकरणातिरिक्तसंबन्धाभावादित्यर्थः । सर्वत्र तस्यास्तन्निमित्तस्य च कर्मादे-

स्वस्वामिभावादित्यन्वयः ॥ ननु राज्ञः पुरुष इत्यत्र राजा पुरुषस्य किंचिद्ददातीति राजा कर्ता, पुरुषः संप्रदानं भवतु नाम, राज्ञो वस्त्रम्, विप्रस्य गौः, विप्रस्य तिलाः, इत्यादौ तु तदसंभवाच्छेषत्वं भविष्यतीत्यत आह—भाष्ये—एतस्वं नामेति । तत्र याच्ञाश-ब्देन तत्पूर्वकः प्रतिग्रहो लक्ष्यते ॥ अपहरणादिति । यथा युद्धे क्षत्रियादीनाम् ॥ क्रयविनिमययोर्भेदमाह—परिवर्त्तनादिति ॥

(समाधानभाष्यम्)

एवं तर्हि कर्मादीनामविवक्षा शेषः ॥

(प्रदीपः) **एवं तर्हीति** । क्रियाकारकसंबन्धोपि सर्वत्र वस्तुस्थित्यास्ति तन्निमित्तश्च स्वस्वामिभावादिरपि । तत्र स्वस्वा-मिभावादिविवक्षायां सन्नपि क्रियाकारकसंबन्धो न विवक्ष्यते ॥

(उद्योतः) न विवक्ष्यत इति । न हि यथावस्तुस्थितास्ति तत्तदभिधातव्यं यदेव विवक्षितं तदेव कार्यकृदिति भावः । वृक्षस्य शाखेत्यादावप्याधाराधेयभावमूलकोऽवयवावयविभाव इति बोध्यम् ॥

(आक्षेपभाष्यम्)

कथं पुनः सतो नामाविवक्षा स्यात्? ॥

(समाधानभाष्यम्)

सतोप्यविवक्षा भवति । तद्यथा—अलोमिका एडका, अनुदरा कन्येति ॥ असतश्च विवक्षा भवति । तद्यथा—समुद्रः कुण्डिका । विन्ध्यो वर्धि-तकमिति ॥

(प्रदीपः) **अलोमिकेति** । लोमकार्याकरणात्सतामपि लोम्नामविवक्षा । **अनुदरेति** । सदप्युदरं महत्त्वाभावप्रतिपा-दनाय न विवक्ष्यते ॥ **असतश्चेति** । दृष्टान्तरूपेणेदमुपा-त्तम् असतो यथा विवक्षा तथा सतोप्यविवक्षेत्यर्थः ॥ **समुद्रः कुण्डिकेति** । कुण्डिकायां बहुपानीयसंभवप्रतिपादनाय समु-द्रत्वमारोप्यते ॥ **विन्ध्यो वर्धितकमिति** । वर्धितक-शब्देन मूले स्थूलमग्रे सूक्ष्मं विशिष्टसंस्थानयुक्तं भक्तमुच्यते । तस्य महत्त्वप्रतिपादनाय विन्ध्यत्वमसदारोप्यते ॥

(उद्योतः) असतो विवक्षायाः प्रकृते न संगतिरत आह—दृष्टान्तेति ॥

(शेषग्रहणप्रयोजनाधिकरणम्)

(आक्षेपभाष्यम्)

किमर्थं पुनः शेषग्रहणम्? ॥

(प्रदीपः) अर्थनियमपक्षे शेषग्रहणस्य प्रत्याख्यानाय वि-चारः क्रियते—**किमर्थमिति** ॥

(१५२७ समाधानवार्तिकम् ॥ १)

॥ * ॥ प्रत्ययावधारणाच्छेषवचनम् ॥ * ॥

(भाष्यम्) **प्रत्ययावधारणाच्छेषग्रहणं कर्तव्यम् । प्रत्यया नियताः, अर्था अनियताः । तत्र षष्ठी प्राप्नोति । तत्र शेषग्रहणं कर्तव्यं षष्ठीनियमार्थम्—शेष एव षष्ठी भवति, नान्यत्रेति ॥**

(उद्योतः) भाष्ये—तत्र षष्ठी प्राप्नोतीति । पर्यायेणेति भावः । परत्वेति नियमेन यौगपद्यासंभवात् ॥

(१५२८ समाधानवार्तिकम् ॥ २)

॥ * ॥ अर्थावधारणाद्वा ॥ * ॥

(भाष्यम्) **अथ वा अर्था नियताः, प्रत्यया अनियताः, ते शेषेऽपि प्राप्नुवन्ति । तत्र शेषग्रहणं कर्तव्यं शेषनियमार्थम्—शेषे षष्ठ्येव भवति नान्येति ॥**

(शेषग्रहणप्रत्याख्यानभाष्यम्)

अर्थनियमे शेषग्रहणं शक्यमकर्तुम् । कथम्? । अर्था नियताः, प्रत्यया अनियताः । ततो व-क्ष्यामि—षष्ठी भवतीति । तन्नियमार्थं भविष्यति—यत्र षष्ठी चान्या च प्राप्नोति तत्र षष्ठ्येव भव-तीति ॥

(प्रदीपः) **तन्नियमार्थमिति** । यथा समे देशे य-जेतेति समविषमयोः पर्यायेण प्रसक्ते विषमस्थाने समविधि-र्विषमनिवारणफलत्वान्नियमः संपद्यते । तथा षष्ठीविधिर्द्वितीया-यादिनिवारणफलः ॥

(उद्योतः) ननु स्वादिवाक्येन षष्ठ्यामपि पर्यायेण प्राप्तायां पुनः षष्ठीविधानमप्राप्तांशे विध्यर्थं न तु नियमार्थमित्यत आह—समे इति । एवं च मीमांसकमतसिद्धोऽयं नियम इति भावः । व्याकरणे तु परिसंख्यापि नियमपदेनोच्यते । अर्थनियमेऽपि उत्तरार्थं शेषग्रहणमावश्यकमिति बोध्यम् ॥ शक्यमकर्तुमित्यस्याशक्यं कर्तुं शक्यमित्यर्थः ॥

(१५२९ आक्षेपवार्तिकप्रथमखण्डम् ॥ ३)

॥ * ॥ षष्ठी शेष इति चेद्विशेष्यस्य प्रतिषेधः ॥ * ॥

(भाष्यम्) **षष्ठी शेष इति चेद्विशेष्यस्य प्रतिषेधो वक्तव्यः । राज्ञः पुरुष इत्यत्र राजा विशेषणम्, पुरुषो विशेष्यः । तत्र प्रातिपदिकार्थो व्यतिरिक्त इति कृत्वा प्रथमा न प्राप्नोति । तत्र षष्ठी स्यात् तस्याः प्रतिषेधो वक्तव्यः ॥**

(प्रदीपः) **षष्ठीशेष इति चेदिति** । अस्मिन् सूत्र-न्यासे दोषः, संबन्धस्य द्विष्ठत्वात् प्रधानादपि षष्ठीप्रसङ्गः । व्याकरणान्तरे तु गुणे षष्ठीतिवचनान्नास्ति दोषः ॥

(उद्योतः) ननु शेषग्रहणाभावेऽपि दोषस्तस्यैव न्यासान्त-रस्य चादर्शनेन 'इति चेद्' इत्यनुपपन्नमत आह—व्याकरणान्तरे त्विति । भाष्ये—व्यतिरिक्त इत्यस्य प्रातिपदिकार्थातिरिक्तया राजनिरूपितविशेष्यतया सहित इत्यर्थः ॥ यत्तु षष्ठ्यर्थसंबन्धस्यां-शेनोभयनिष्ठतया प्रतीतेस्तेन प्रातिपदिकार्थातिरिक्तेन सहित इत्यर्थ इति ॥ तन्न । पुरुषे स्वामिकृतं स्वत्वमपि षष्ठ्याभिहितमिति

पुरुषशब्दात् **षष्ठी** नेत्यग्रिमभाष्येण तस्य षष्ठ्यर्थत्वोक्त्या वाक्यार्थत्वकथनानुपपत्तेः ॥ भाष्ये—**षष्ठी स्यादिति** । कारकप्रातिपदिकार्थव्यतिरिक्तत्वात् षष्ठ्येव स्यादित्यर्थः ॥

(१५३० आक्षेपवार्तिकद्वितीयखण्डम् ॥ ४)

॥ * ॥ तत्र प्रथमाविधिः ॥ * ॥

(भाष्यम्) **तत्र षष्ठीं प्रतिषिध्य प्रथमा विधेया । राज्ञः पुरुषः ॥**

(प्रदीपः) प्रतिषिद्धायामपि षष्ठ्यां प्रातिपदिकार्थमात्रे विधीयमानायाः प्रथमायाः संबन्धस्याधिकस्य भावादप्रसङ्ग इति मत्वाह—**तत्र प्रथमेति** ॥

(उद्द्योतः) **संबन्धस्य** विशेष्यविशेषणभावस्य ॥

(आक्षेपपरिहारभाष्यम्)

उक्तं पूर्वेण* । किमुक्तम् ! । '*न वा वाक्यार्थत्वाद्'इति । यदत्राधिक्यं वाक्यार्थः सः ॥

(प्रदीपः) **यदत्रेति** । राज्ञ इत्येतत्पदसंनिधाने पुरुषस्य संबन्धित्वं प्रतीयते नान्यथा । पुरुषप्रातिपदिकं तु स्वार्थमात्रे वर्तत इति प्रथमा सिध्यतीत्यर्थः ॥

(उद्द्योतः) भाष्ये—**यदत्राधिक्यमिति** । उक्तरूपम् । पदान्तरसंनिधाने प्रतीयमानत्वाच्च वाक्यार्थत्वम् ॥ **संबन्धित्वम्** उक्त—संबन्धकृतं राजनिरूपितं विशेष्यत्वम् ॥

(आक्षेपभाष्यम्)

कुतो नु खल्वेतत्—'पुरुषे यदाधिक्यं स वाक्यार्थ इति, न पुना राजनि यदाधिक्यं स वाक्यार्थः स्यात्' ॥

(प्रदीपः) **कुतो न्विति** । पुरुषपदसंनिधान एव राज्ञः संबन्धित्वावगमो नान्यथेति ततोपि प्रथमाप्रसङ्गः ॥

(उद्द्योतः) **राज्ञः संबन्धित्वावगमः** संबन्धकृतो विशेषणत्वावगमः।एवञ्च विशेषणत्वस्य वाक्यार्थत्वे तन्नियामकसंबन्धोऽपि वाक्यार्थ एवास्त्विति ततोपि प्रथमाप्रसङ्गः इत्यर्थः ॥

(समाधानभाष्यम्)

अन्तरेणापि पुरुषशब्दस्य प्रयोगं राजनि सोर्थो गम्यते, न पुनरन्तरेण राजशब्दस्य प्रयोगं पुरुषे सोर्थो गम्यते ॥ अस्ति कारणं येनैतदेवं भवति ॥ किं कारणम् ? । राजशब्दाद्धि भवान् षष्ठीमुच्चारयति । अङ्ग हि भवान् पुरुषशब्दादप्युच्चारयतु गंस्यते सोर्थः ॥

(प्रदीपः) **अन्तरेणेति** । राज्ञ इति केवलेपि पद उच्चार्यमाणे संबन्धित्वमनियतप्रतियोगि राज्ञो गम्यते । यस्माद्राजा परोपकारित्वेन विवक्षितो न स्वनिष्ठत्वेन ॥

(उद्द्योतः) **संबन्धित्वम्** । विशेषणत्वम् ॥ **अनियतप्रतियोगीति** । अनियतविशेष्यनिरूपितमित्यर्थः । तदाह—**राजा परोपकारित्वेनेति** । विशेषणत्वेनेत्यर्थः ॥ न **स्वनिष्ठत्वेन** न स्वार्थनिरूपितविशेष्यतया ॥भाष्ये—**पुरुषे सोऽर्थ इति** । किंचिदन्यपदार्थनिरूपितं विशेष्यत्वम् ॥

(आक्षेपभाष्यम्)

ननु च नैतेनैवं भवितव्यम् । न हि शब्दकृतेन नामार्थेन भवितव्यम् । अर्थकृतेन नाम शब्देन भवितव्यम् ॥

(प्रदीपः) **ननु च नैतेनेति** । नहि शब्दस्य भावाभावाभ्यामर्थस्य भावाभावौ क्रियेते । किं तर्ह्यर्थस्य प्रतिपिपादयिषया विषयीकरणाकरणाभ्यां शब्दस्योच्चारणानुच्चारणलक्षणौ भावाभावावित्यर्थः । तत्र परोपकारित्वेन राज्ञो विवक्षितत्वात् षष्ठी भवति, पुरुषस्य तूपकार्यतया स्वनिष्ठत्वेन विवक्षितत्वात् प्रथमा । तदुक्तं हरिणा—

द्विष्ठोप्यसौ परार्थत्वाद् गुणेषु व्यतिरिच्यते ।
तत्राभिधीयमानश्च प्रधानेप्युपयुज्यते ॥ इति ॥

(उद्द्योतः) शब्दार्थयोर्नित्यत्वात् शब्दकृतमर्थकृतमित्यनुपपन्नमत आह—**किं तर्ह्यर्थस्येति** । अर्थस्य शब्दोच्चारणप्रयोजकत्वाच्छब्देऽर्थकृतत्वमिवार्थे शब्दकृतत्वं नेति भावः ॥ **प्रतिपिपादयिषयेत्यस्य विषयीकरणाकरणाभ्या**मित्यनेनान्वयः । तदाह—**तत्रेति** ॥ **परोपकारित्वेन** विशेषणत्वेन ॥ **षष्ठी भवतीति** । तस्य विशेषणतानियामकसंबन्धबोधिका तद्गतविशेषणताबोधिका च षष्ठी भवतीत्यर्थः ॥ **पुरुषस्य तूपकार्यतयेति** ॥ अविवक्षितत्वेनेति शेषः । राजादिपदासन्निधानेन तस्योपकार्यतयान्यनिरूपितविशेष्यतयाऽविवक्षितत्वेन **स्वनिष्ठतया** स्वार्थमात्रनिष्ठविशेष्यतया **विवक्षितत्वा**दन्तरङ्गत्वात्प्रथमेत्यर्थः ॥

द्विष्ठ इति । **असौ** संबन्धः ॥ **परार्थत्वात्** परं विशेषणत्वमर्थः प्रयोजनं यस्य तत्त्वाद्विशेषणतानियामकत्वादित्यर्थः । भेदे सति विशेषणतया विवक्षितस्य संबन्धं विना विशेषणत्वासंभवेन तदाकाङ्क्षितत्वात्तत्र संबन्धो **व्यतिरिच्यते** उद्भूततया प्रतीयत इति तत्र षष्ठीत्यर्थः । विशेष्यस्य तु स्वनिष्ठत्वादेव न विशेष्यतानियामकसंबन्धाकाङ्क्षेति भावः ॥ **तत्र** विशेषणशब्देन षष्ठ्यादिना प्रतीयमानः ॥ **प्रधानेऽप्युपयुज्यते** । तस्य द्विष्ठत्वस्वभावत्वाद्राजादिनिरूपितविशेष्यतायाः राजादिपदसंनिधाने प्रतीयमानाया उपकारको भवतीत्यर्थः ॥

(समाधानभाष्यम्)

तदेतदेवं दृश्यताम्—अर्थरूपमेवैतदेवंजातीयकं येनान्तरेणापि पुरुषशब्दस्य प्रयोगं राजनि सोर्थो गम्यते ॥ किं पुनस्तत् ? । स्वामित्वम् ॥ किं कृतं पुनस्तत् ? । स्वकृतम् ॥ तद्यथा—प्रातिपदिकार्थानां क्रियाकृता विशेषा उपजायन्ते तत्कृताश्चाख्याः प्रादुर्भवन्ति—कर्म करणमपादानं संप्रदानमधिक

रणम्—इति। ताश्च पुनर्विभक्तीनामुत्पत्तौ कदाचिन्निमित्तत्वेनोपादीयन्ते कदाचिन्न ॥

(प्रदीपः) **स्वामित्वमिति**। स्वस्वामिसंबन्ध इत्यर्थः। **समासकृत्तद्धितेषु संबन्धाभिधान**मिति वचनात् ॥ **स्वकृतमिति**। ततश्चानियतं स्वमपेक्ष्य प्रथममेव संबन्धाश्रया षष्ठी उत्पाद्यते। पुरुषशब्दसन्निधौ तु स्वविशेषप्रतिपत्तिरित्यर्थः ॥ **तद्यथेति**। प्रातिपदिकार्थानामित्यर्थः। क्वचित् तु **प्रातिपदिकार्थानामि**त्येव पाठः ॥ **क्रियाकृता इति**। क्रियाफलापेक्षया शक्तय आश्रीयन्त इत्यर्थः ॥ **तत्कृताश्चेति**। शक्तिनिमित्ताः संज्ञा इत्यर्थः ॥ **कदाचिदिति**। यदा क्रियां प्रति व्यापारावेशविवक्षा भवति दात्रेण लुनातीति ॥ **कदाचिन्नेति**। यदा योग्यतामात्रविवक्षा भवति दात्रं लवने करणमिति ॥

(उद्योतः) [राजनि सोर्थ इति। विशेषणत्वं संबन्धश्चेत्यर्थः।] किं पुनस्तदिति भाष्ये—सोऽर्थ इत्यत्र तच्छब्दार्थः कः किं विशेषणत्वमेवातोन्योपीति प्रश्नः ॥ उत्तरम्—**स्वामित्वमिति**। स्वामित्वं तत्कृतं विशेषणत्वं चेत्यर्थः ॥ **स्वस्वामिसंबन्ध इति**। तन्मूलकं विशेषणत्वं चेत्यपि बोध्यम्। स्वस्वामिनोः संबन्धः स्वत्वस्वामित्वोभयरूपः सचैकदेशेन स्वनिष्ठः स्वामिनिष्ठश्चेति बोध्यम् ॥ **समासेति**। स्वशब्दादैश्वर्ये आमिनचि स्वामिन्शब्द इति भावः ॥ भाष्ये—**किं कृतमिति**। स्वत्ववद्वाचकपदानुपादानादिति भावः ॥ उत्तरयति—**स्वकृतमिति**। सामान्यतः स्वमात्रनिरूपितमित्यर्थः ॥ नन्वेवं पुरुषशब्दोपादानं व्यर्थमत आह—**पुरुषेति** ॥ ननु स्वामित्वप्रतिपिपादयिषायां राजा स्वामीति प्रयुज्यतां किमिति षष्ठीप्रयोगः? प्रयोगाप्रयोगयोर्विषयविभागश्च कः। सामान्यनिरूपितं स्वामित्वं च कथम्? इत्याशङ्क्य दृष्टान्तेनोपपादयति—भाष्ये—**तद्यथेति** ॥ **क्रियाकृताः** क्रियासामान्यनिरूपिताः ॥ **उपजायन्ते** विवक्ष्यन्ते। तदेवाह—**आश्रीयन्त इति** ॥ **यदेत्यादि**। उभयत्रापि **भवती**त्यस्य तदेति शेषः ॥

(आक्षेपभाष्यम्)

कदा विभक्तीनामुत्पत्तौ निमित्तत्वेन नोपादीयन्ते?॥

(समाधानभाष्यम्)

यदा व्यभिचरन्ति प्रातिपदिकार्थम्। यदा हि न व्यभिचरन्ति, आख्याभूता एव तदा भवन्ति—कर्म करणमपादानं संप्रदानमधिकरणमिति ॥

(प्रदीपः) **व्यभिचरन्तीति**। यदा प्रातिपदिकार्थस्य क्रियावेशविवक्षायां शक्तिलक्षणार्थातिरेको भवति तदा प्रातिपदिकार्थतां शक्तयो न प्रतिपद्यन्त इत्यर्थः ॥ **यदा हीति**। अपरोपकारित्वेन स्वनिष्ठतया यदा प्रातिपदिकार्थो विवक्षित इत्यर्थः। तदेवं दात्रेणेति यथा क्रियापेक्षया भवति तथा राज्ञ इति स्वापेक्षया। यथा च स्वनिष्ठत्वाश्रयेण दात्रं करणमिति भवति तथा राजा स्वामीत्युक्तं भवति ॥ **आख्याभूता इति**। ताः शक्तयः संज्ञामेव प्राप्ताः न तु विभक्त्युत्पत्तिं प्रयोजयन्तीत्यर्थः। तदुक्तम्—

स्वशब्दैरभिधाने तु स धर्मो नाभिधीयते।
विभक्त्यादिभिरेवासावुपकारः प्रतीयते ॥ इति ॥

(उद्योतः) **शक्तिलक्षणार्थातिरेक इति**। अयं भावः सर्वे पदार्थाः सर्वशक्तिमन्तः शक्तिभिश्च धर्मिणां भेदाभेदौ। तत्र भेदविवक्षायां विभक्तयः। अभेदविवक्षायां तु करणादिशब्दैरभिधानम्। भेदविवक्षा च क्रियासामान्ये क्रियाविशेषे वा विशेषणत्वेनान्वयविवक्षायामेव भवतीति ॥ इयमेव च क्रियां प्रति व्यापारावेशविवक्षा यस्यां विशेषणत्वविवक्षया प्रातिपदिकार्थता विभक्तिसमभिव्याहारं विनापि तदर्थता ॥ **अपरोपकारित्वेनेति**। इतरा(र)विशेषणत्वेनेत्यर्थः ॥ **स्वनिष्ठतया** स्वार्थनिरूपितविशेष्यतया ॥ दृष्टान्तमुपपाद्य दार्ष्टान्तिके योजयति—**तदेवमिति**। एवं च स्वप्रकृत्यर्थस्य विशेषणभावेऽपि विभक्त्यर्थ इति बोध्यम् ॥ **संज्ञामेवेति**। संज्ञा व्यवहारः करणत्वादिव्यवहारस्तमेवेत्यर्थः ॥ विभक्त्यभावेन शास्त्रीयसंज्ञाया अनुपयोगात् ॥ **स धर्मः** शक्तिरूपः ॥ **नाभिधीयते** सामान्यतो विशेषतो वा पृथक् नाभिधीयते। फलाश्रयत्वादिनैव ततो बोधादिति भावः ॥ **उपकारः**। स्वप्रकृत्यर्थस्येतरविशेषणतानियामकः। कर्मादिपदेन संबन्धपदेन चोक्तस्य न शक्तिरूपता, नापि संबन्धरूपता। अत्र कर्मादिशब्दैर्नाभिधीयते इत्युक्त्या कृदन्ते सर्वत्र तदनभिधानमिति लभ्यते ॥ न हि कृतकर्मशब्दयोः कश्चिद्विशेष उभयत्रापि कर्मणि प्रत्ययात्। **विभक्त्यादिभिरि**त्यत्रापि (दि) शब्द आश्रयवाचीति बोध्यम् ॥

(आक्षेपभाष्यम्)

यथैव तर्हि राजनि स्वकृतं स्वामित्वं तत्र षष्ठी भवति। एवं पुरुषेऽपि स्वामिकृतं स्वत्वं तत्र षष्ठी प्राप्नोति ॥

(प्रदीपः) **पुरुषेपीति**। संबन्धस्य द्विष्ठत्वाद् द्वाभ्यां षष्ठी प्राप्नोतीत्यर्थः। शक्तिस्तु प्रातिपदिकार्थस्यैव न क्रियाया इति विशेषः ॥

(उद्योतः) उक्तमाशयमजानानो **यस्मादधिकमिति** सूत्रोक्तरीत्या अधि ब्रह्मदत्ते पञ्चाला इत्यत्रापि पञ्चालशब्दाद् द्वितीयेव प्रकृते पुरुषपदात् षष्ठी[प्राप्नोतीति] शङ्कते—भाष्ये—**यथैव तर्हीति॥** ननु षष्ठ्या उभयत्रापत्तिवद्द्वितीयादीनामप्युभयत्रापत्तिः कुतो न कृतेत्यत आह—**शक्तिस्त्विति**। संबन्धस्य तु स्वत्वस्वामित्वोभयरूपतयोभयवृत्तित्वमिति भावः ॥ यद्यप्येवं क्रियाकारकभावसंबन्धो द्विष्ठ एव, तथापि **कर्मणी**त्यादिशास्त्रबलादिह स्वामित्वस्येव तत्र शक्तेरपि तदर्थत्वान्न दोषः। क्रियावाचकस्याप्रातिपदिकत्वादपि न तदापत्तिरिति बोध्यम् ॥

(समाधानभाष्यम्)

राजशब्दादुत्पद्यमानया षष्ठ्याभिहितः सोर्थ इति कृत्वा पुरुषशब्दात्षष्ठी न भविष्यति ॥

(प्रदीपः) **राजशब्दाद्विति।** गुणप्रधानभावेनार्थद्वयमवस्थितमित्युक्तमेतत्। तत्र संबन्धो गुणे पदं न्यस्य द्विष्ठत्वात् प्रधानमपि संस्पृशति। गुणश्च प्रधानोपकाराय प्रवृत्तो रूपान्तरमाश्रयति, प्रधानं तु स्वनिष्ठमेव न तु रूपान्तरं भजते॥

(उद्द्योतः) **षष्ठ्याभिहितइति** भाष्ये अयं भावः—कटं भीष्म इत्यादौ प्रकारान्तरेण द्वितीयासाधनारपरिगणनमनावश्यकम्। राजपदोत्तरषष्ठ्या स्वामित्वस्योक्तावपि पुरुषे स्वत्वं विना पुरुषनिरूपितस्वामित्वाप्रत्ययेन तत्र तत्त्वमप्यर्थायातमिति॥ नन्वर्थलभ्येऽपि स्वामित्वे राज्ञः स्वमित्यादौ षष्ठी दृश्यते। किं च वार्त्तिकमते इदं परिगणनेन विरुद्धमित्यतः पूर्वमुक्तमभिप्रायं स्मारयति—**गुणप्रधानभावेनेति।** **रूपान्तरं** विशेषणतानियामकसंबन्धवत्त्वम्। पदान्तरासमभिव्याहारेऽपीति भावः॥ **प्रधानं त्विति।** पदान्तरासमभिव्याहारे इति शेषः॥ **रूपान्तरम्।** अन्यनिरूपितविशेष्यतानियामकसंबन्धम्। तस्या एवाप्रतीतेरिति भावः॥ अनया रीत्या पञ्चालशब्दाद्द्वितीयावारणमपि कर्तुं शक्यम्॥

(आक्षेपभाष्यम्)

न तर्हीदानीमिदं भवति—पुरुषस्य राजेति?॥

(प्रदीपः) पुरुषस्येति षष्ठ्या नैव भाव्यमिति भ्रान्त्या चोदयति—**न तर्हीति॥**

(समाधानभाष्यम्)

भवति। राजशब्दात्तु तदा प्रथमा॥

(प्रदीपः) **भवतीति।** यदा पुरुषस्य गुणभावो राज्ञस्तु विशेष्यत्वं तदा पुरुषस्य राजेति भवत्येवेत्यर्थः॥

(उद्द्योतः) **तदा पुरुषस्य राजेति।** पुरुषसंबन्धी राजेति तदा बोध इति भावः॥ ५०॥

(आक्षेपभाष्यम्)

न तर्हीदानीमिदं भवति—राज्ञः पुरुषस्येति?॥

(समाधानभाष्यम्)

भवति बाह्यमर्थमभिसमीक्ष्य॥ षष्ठी शेषे॥५०॥

(प्रदीपः) **भवति बाह्यमिति।** एकस्यापि वस्तुनो भिन्नविषयो गुणप्रधानभावो न विरुध्यते॥ ५०॥

(३२५ प्रतिपदषष्ठीसूत्रम्॥ २।३।३ आ. ३ सू.)

५१० अधीगर्थदयेशां कर्मणि॥ २।३।५२॥

(भावे प्रत्ययसाधनाधिकरणम्)

(१५३० आक्षेपवार्तिकम्॥१)

॥*॥ कर्मादिष्वकर्मकवद्वचनम्॥*॥

कर्मादिष्वकर्मकवद्भावो वक्तव्यः॥ किं प्रयोजनम्?। अकर्मकाणां भावे लो भवतीति भावे लो यथा स्यात्—मातुः स्मर्यते, पितुः स्मर्यते इति॥ अथ वत्करणं किमर्थम्?। स्वाश्रयमपि यथा स्यात्—माता स्मर्यते, पिता स्मर्यत इति॥

(प्रदीपः) **अधीगर्थ॥ ५२॥ मातुः स्मरतीति।** मातृस्मरणयोरवस्थानादिक्रियानिमित्तः संबन्ध इति केचिदाहुः। अन्ये तु स्मरणस्य क्रियारूपत्वात् क्रियान्तरमन्तरेणैव द्रव्येण संबन्धोपपत्तिमाहुः। यथा द्वयोः काष्ठयोर्जतुकृतः संश्लेषो जतुनस्तु काष्ठेन स्वत एव न जत्वन्तरकृतः॥ **कर्मादिष्विति।** आदिशब्दोऽत्राश्रयवाची। यथा—

विष्णुरादिः पृथासूनोर्भीष्मादिश्च सुयोधनः॥
ते जयन्ति रणे शत्रून् येषां विष्णुः समाश्रयः॥

इति। तेन कर्माश्रयाः द्वितीयाविधिनिमित्तभावेनोपात्ताः सकर्मका अधीगर्थादयः प्रेष्यब्रुपर्यन्ताः कर्मादिशब्देनोच्यन्ते॥ **अकर्मकाणामिति।** तेन मातुः स्मर्यत इति भावे लकृत्यक्तखलर्था भवन्ति, कर्मणि तु लादिषु विधीयमानेषु तैरभिहितत्वात्कर्मणः षष्ठ्या न भाव्यमिति प्रथमैव भवति माता स्मर्यत इति॥ **वत्करणं किमर्थमिति।** विनापि वतिनातिदेशः सिध्यति परार्थे शब्दप्रयोगात्॥ **स्वाश्रयमपीति।** नाप्राप्ते स्वाश्रये आरभ्यमाणोतिदेशस्तद् बाधेत॥

(उद्द्योतः) **अधीगर्थ॥ ५२॥** एषां कर्मणि शेषत्वेन विवक्षिते षष्ठीति सिद्धान्ते सूत्रार्थः। कर्मादीनामविवक्षा च शेष इति बोध्यम्॥ ननु मातुः कर्मत्वाविवक्षायां किं निमित्तेन संबन्धेन मात्रादेः स्मरणेऽन्वय इत्यत आह—**मातुरिति॥ अवस्थाने** विषयत्वभवने माता कर्त्री स्मरणमधिकरणं तन्निमित्तकं विषयत्वं संबन्ध इत्यर्थः॥ **अन्येस्त्विति।** स्वकर्मत्वकृतो विषयविषयिभाव एव संबन्ध इति भावः॥ कर्मव्यतिरिक्तस्याभावादादिशब्दवैफल्यमत आह—**आदिशब्द इति। द्वितीयाविधिनिमित्तभावेनेति।** द्वितीयापवादषष्ठीविधिनिमित्तभावेनेत्यर्थः। दिवस्तदर्थस्य इत्यादौ विषये **विभाषोपसर्गे द्वितीया ब्राह्मणे** इति सूत्रद्वयारम्भसामर्थ्येनात्र प्रकरणे शेषग्रहणानुवृत्तिर्नेति वार्त्तिकारम्भः। यदा भावे लस्तदैवानभिहितत्वात् षष्ठी। यदा कर्मणि तदाऽभिहितत्वात्प्रथमैव तदाह—**कर्मणि त्विति॥ विनापीति।** अब्रह्मदत्ते ब्रह्मदत्तशब्दप्रयोग इवेत्यर्थः॥ वत्यभावे सिद्धिमुपपादयति—**नाप्राप्ते इति॥** वस्तुतस्तु अयं क्षत्रियो ब्राह्मण इत्यादौ लोके वतिं विनाप्यतिदेशविषये स्वाश्रयानिवृत्तिदर्शनादिदं चिन्त्यम्। किं तु वत्यभावेऽकर्मकसंज्ञेयं स्यात्। तथा च स्वाश्रयं न स्यादिति भाष्यतात्पर्यम्॥

(१५३१ विपक्षबाधकं वार्तिकप्रथमखण्डम्॥ २)

॥*॥ कर्माभिधानेहि लिङ्गवचनानुपपत्तिः॥*॥

(भाष्यम्) **कर्माभिधाने हि लिङ्गवचनयोरनुपपत्तिः स्यात्। मातुः स्मृतम्। मात्रोः स्मृतम्। मातृणां स्मृतमिति। मातुर्यल्लिङ्गं वचनं तत्स्मृतशब्दस्यापि प्राप्नोति॥**

(प्रदीपः) कर्माभिधाने हीति । यद्यकर्मकवद्भावो न विधीयते तदा लादिभिः कर्मैवाभिधातव्यं न भावः । ततस्तत्सामानाधिकरण्यात् क्तान्तादीनां तदीयलिङ्गसंख्याप्रसङ्गो यथा माता स्मृतेति । भावे तूत्पत्तौ क्तादीनां नपुंसकत्वमेकवचनं च भवति ॥

(उद्द्योतः) भाष्ये कर्मवद्भावस्य फलान्तरमाह—कर्माभिधाने हीति । हिश्चार्थे ॥

(१५३२ विपक्षबाधकं वार्तिकद्वितीयखण्डम् ॥ २)

॥ * ॥ षष्ठीप्रसङ्गश्च ॥ * ॥

(भाष्यम्) षष्ठी च प्राप्नोति ॥ कुतः ? । स्मृतशब्दान्मातुः सामानाधिकरण्यात्षष्ठी प्राप्नोति ॥

(प्रदीपः) षष्ठीप्रसङ्गश्चेति । यदा स्मृतशब्दे कर्मणि क्तो विधीयते तदा मातृशब्दसामानाधिकरण्याद् वाक्यवस्थापेक्षया यथा मातृशब्दात् षष्ठी भवति तथा स्मृतशब्दादपि स्यादित्येके व्याचक्षते ॥ अन्ये त्वाहुः—अनभिहिताधिकारानपेक्षणेन यथा मातृशब्दात् कर्मणि षष्ठी भवत्येवं स्मृतशब्दादपि स्यादिति ॥

(उद्द्योतः) इत्येके इति । तत्रेष्टापत्तिरित्यत्रारुचिः ॥

(व्याख्यान्तरभाष्यम्)

अपर आह—

॥ * ॥ षष्ठीप्रसङ्गश्च ॥ * ॥

षष्ठी च प्रसज्येत । कुतः ? । मातृशब्दात् । स्मृतशब्देनाभिहितं कर्मेति कृत्वा षष्ठी न प्राप्नोति ॥

(प्रदीपः) ननु विद्यमानोऽप्यनभिहिताधिकारः कथं नापेक्ष्यत इत्याशङ्क्याह—अपर आहेति ॥ प्रसज्येतेति ॥ प्रापणीयेत्यर्थः ॥

(तृतीयाक्षेपभाष्यम्)

तर्हि वक्तव्यम् ? ॥

(समाधानभाष्यम्)

न वक्तव्यम् । अविवक्षिते कर्मणि षष्ठी भवतीति ॥ किं वक्तव्यमेतत् ? । नहि ॥ कथमनुच्यमानं गंस्यते ? । शेष इति वर्तते ॥ शेषश्च कः ? । कर्मादीनामविवक्षा शेषः । यदा च कर्म विवक्षितं भवति तदा षष्ठी न भवति । तद्यथा—स्मराम्यहं मातरम्, स्मराम्यहं पितरमिति ॥ अधीगर्थ ॥५२॥

(प्रदीपः) शेष इतीति । प्रकरणं चेदं समासप्रतिषेधार्थमिति समासप्रकरणे व्याख्यातम् । तेन मातुः स्मृतमिति षष्ठीसमासो न भवति । उक्तं च हरिणा—

साधनैर्व्यपदिष्टे च श्रूयमाणक्रिये पुनः ।
प्रोक्ता प्रतिपदं षष्ठी समासस्य निवृत्तये ॥

इति ॥ ५२ ॥

(उद्द्योतः) भाष्ये—अविवक्षिते कर्मणीति । एवं चाविवक्षितकर्मकत्वेनाकर्मकत्वाद्भावे लादयः सिद्धा इति भावः ॥ नन्वेवं शेषषष्ठ्यैव सिद्धे प्रकरणमिदं व्यर्थमत आह—प्रकरणञ्चेति । मण्डूकानुवृत्तेरयुक्तत्वात् पूर्वसूत्रेऽपि शेष इत्यस्य संबन्धो बोध्यः ॥ साधनैरिति । करणकर्मकारकैर्व्यपदिष्टे विगतोपदेशे विगतव्यवहारे शेषत्वेन विवक्षित इति यावत् ॥ श्रूयमाणक्रिये इति । स्वरूपकथनम् । नच शेषत्वाविवक्षायां कृद्योगषष्ठ्या समासस्य दुर्वारत्वेनेदं व्यर्थम्, आदिकर्मणि कर्तरि क्तप्रत्ययान्तस्मृतादिभिः समासवारणार्थत्वात् ॥ न हि तत्र कृद्योगलक्षणा षष्ठी, न लोकेति निषेधादिति बोध्यम् ॥ ५२ ॥

—⟶◇⟵—

(३२६ प्रतिपदषष्ठीसूत्रम् ॥ २। ३। ३। आ. ४ सु.)

५१२ रुजार्थानां भाववचनानामज्वरेः ॥ २।३।५४ ॥

(१५३३ शेषपूरकवार्तिकम् ॥ १)

॥ * ॥ अज्वरिसंताप्योः ॥ * ॥

(भाष्यम्) अज्वरिसंताप्योरिति वक्तव्यम् । इहापि यथा स्यात्—चोरं सन्तापयति, वृषलं सन्तापयति ॥

(आक्षेपभाष्यम्)

अथ किमर्थं 'भाववचनानाम्' इत्युच्यते । यावता रुजार्था भाववचना एव भवन्ति ? ॥

(प्रदीपः) रुजार्थानाम् ॥ ५४ ॥ यावतेति । धातूनां भाववाचित्वाव्यभिचारात् ॥

(समाधानभाष्यम्)

भावकर्तृकाद्यथा स्यात् । इह मा भूत्—नदीकूलानि रुजतीति ॥ रुजार्थानाम् ॥ ५४ ॥

(प्रदीपः) भावकर्तृकादिति । ल्यब्लोपे कर्मणि पञ्चमी । भावकर्तृकमाश्रित्येत्यर्थः । अथ वा भावकर्तृकधात्वर्थकर्मचोरादिकं भावकर्तृकशब्देनोक्तम् ॥ कथं पुनर्भाववचनानामित्यस्य भावकर्तृकाणामित्यर्थो भवति ? । उच्यते—भावशब्देन घञादिवाच्यसिद्धरूपोऽभिधीयते, न तु साध्यरूपस्तस्य कर्तृत्वासंभवात् । वचनशब्देऽपि प्रत्ययार्थः कर्ता विवक्षितः, कर्तरि ल्युटो विधानात् । प्रकृत्यर्थस्तु वचनक्रिया न विवक्ष्यते । तेन भावो वचनः कर्ता येषां ते भाववचनाः भावकर्तृका इत्यर्थः संपद्यते ॥ अन्ये त्वाहुः—भावे वचनं तेषां ते भाववचनाः सति भावे कर्तरि येषां वचनमुच्चारणम् । भाववधात्वर्थप्रतिपादनाय येषामभिधानमित्यर्थः ॥ नदीकूलानीति । रुजाशब्दो व्याधौ रूढ इत्यत्र प्रसङ्ग एव नास्ति । तस्माद् रुजार्थानामिति धातुमात्रनिर्देशाश्रयमिदं प्रत्युदाहरणम् । रुजाशब्दनिर्देशे तु श्लेष्मा पुरुषं रुजतीति प्रत्युदाहार्यमित्याहुः ॥ ५४ ॥

(उद्द्योतः) रुजार्थानाम् ॥ ५५ ॥ कर्मणि षष्ठीविधानेन भावकर्तृकादित्यनुपपन्नमत आह—श्यल्लोपइति ॥ तत्प्रत्याख्यानपक्षेऽप्याह—अथवेति ॥ कर्तृत्वासंभवादिति । असत्त्वभूतस्य भवत्यर्थातिरिक्ते कर्तृत्वासंभवादिति भावः ॥ कर्त्तरीति । बहुलवचनादित्यर्थः ॥ अन्ये त्विति । बाहुलकाश्रयिकरणबहुव्रीह्याश्रयणं वरमित्यभिमानः ॥ रुजाशब्दइति । अन्यथा रुजार्थानामिति निर्देशोनुपपन्न इति भावः ॥ धातुमात्रेति । धात्वर्थमात्रेत्यर्थः । अकार उच्चारणार्थ इति निर्देशोपपत्तिरिति भावः । तिङन्तं प्रत्युदाहरणं वार्त्तिकमते, शेषग्रहणानुवृत्तेस्तन्मतेऽभावात् ॥ ५४ ॥

—

(३२७ द्वितीयासूत्रम् ॥ २।३।३ आ. ५)

५१८ द्वितीया ब्राह्मणे ॥ २।३।६० ॥

(आक्षेपभाष्यम्)

किमुदाहरणम् ? ॥

(प्रदीपः) द्वितीया ॥ ६० ॥ किमुदाहरणमिति । पूर्वसूत्रे व्यवस्थितविभाषाविज्ञानात्सोपसर्गस्य दीव्यतेः कर्मणि छन्दसि द्वितीयैव भविष्यति गां प्रदीव्यन्तीत्यादाविति प्रश्नः ॥

(समाधानभाष्यम्)

गां निघ्नन्ति । गां प्रदीव्यन्ति । गां सभासद्भ्य उपहरन्ति ॥

(समाधानबाधकभाष्यम्)

नैतदस्ति । पूर्वेणाप्येतत्सिद्धम् ॥

(उद्द्योतः) द्वितीया ब्राह्मणे ॥ ६० ॥ भाष्ये—पूर्वेणापीति । विभाषोपसर्गे इत्यनेनेत्यर्थः ॥

(समाधानभाष्यम्)

इदं तर्हि—गामस्य तदहः सभायां दीव्येयुः ॥ द्वितीया ॥ ६० ॥

(प्रदीपः) गामस्येति । अत्र दिवस्तदर्थस्येति नित्यं षष्ठी प्राप्नोति ॥ अत्र च शेष इति नानुवर्तत इति एतत्सूत्रारम्भात् पूर्वसूत्रारम्भाच्च ज्ञायते ॥ ६० ॥

(उद्द्योतः) दिव इति सूत्रे शेषग्रहणानुवृत्त्या शेषषष्ठी तत्त्वाविक्षायां द्वितीयेतीदमपि सिद्धमतआह—अत्र च शेष इति । दिवस्तदर्थस्येति सूत्रे इत्यर्थः । अत्र शेष इत्यस्य संबन्धे विभाषोपसर्गे इति सूत्रं समासविकल्पफलकं वाच्यम् । तथा च नोपसर्ग इति पूर्वसूत्रनिषेधे शेषषष्ठ्यां समासविकल्पेन रूपद्वयस्य सिद्धतया विभाषाग्रहणं व्यर्थं स्यात् । विभाषोपसर्गे इत्यत्र शेष इत्यस्यासंबन्धे तु वेदेऽपि तेनैव कर्मणि द्वितीयायाः सोपसर्गे सिद्धत्वेन आपाद्यरूपाभावेन निरुपसर्गेऽपि कर्मत्वविवक्षायां दिव इत्यस्याप्रवृत्त्या कर्मणि द्वितीयेत्येव सिद्धतया द्वितीया ब्राह्मणे इत्यस्य वैयर्थ्यापत्तिः । कृति विदं न प्रवर्तत इति पुनर्विधानं समासाभावायेत्यपि न वाच्यमिति भावः ॥ परे तु दिव इति सूत्रे शेष इत्यस्य निवृत्तिर्व्याख्यानादेव । नोपसर्ग इत्यत्र विभाषोपसर्गे इत्यतः पदलाघवाभावात्तिङन्ते रूपद्वयार्थं विभाषाग्रहणस्यावश्यकत्वाच्च । कृति प्रतिपदविधानेति निषेधात् षष्ठीसमासाभाव एव । अत एव तद्भाष्यकृता न प्रत्याख्यातमित्याहुः ॥ परे तु दिव इति सूत्रे शेष इति संबध्यत एव । कर्मादिष्वकर्मकवद्भावनमिति वार्त्तिकरीत्या शतस्य दीव्यत इति भावे इष्टः प्रयोगः सिध्यति । अत एव सकर्मका अधीगर्थादयः प्रेष्यब्रूपर्यन्ताः कर्मादिशब्देनोच्यन्ते इति कैयटः । शेष इत्यनुवृत्त्या वार्त्तिकप्रत्याख्याने तु एतत्सूत्रद्वयप्रत्याख्याने एव भाष्यतात्पर्यम् ॥ अत्र चेति कैयटस्यापि अत्र प्रकरणे इत्यर्थः । एवं चात्रत्यं भाष्यं वार्त्तिकरीत्या ॥ एवं च ज्ञो विदर्थस्य करणइत्येति सूत्रे च न शेषपदसंबन्धो मानाभावात् । अत्र च मण्डूकानुवृत्तिः । अत एव यदा कर्म विवक्षितमित्येवोक्तम् । अन्यथा कर्मादि विवक्षितमिति वदेदित्याहुः ॥ ६० ॥

—

(३२८ षष्ठीसूत्रम् ॥ २ । ३ । ३ आ. ६ सू.)

५१९ प्रेष्यब्रुवोर्हविषो देवतासंप्रदाने ॥ २।३।६१ ॥

(१५३४ शेषपूरकवार्त्तिकम् ॥ १)

॥ * ॥ हविषोऽप्रस्थितस्य ॥ * ॥

(भाष्यम्) **हविषः अप्रस्थितस्येति वक्तव्यम् । इन्द्राग्निभ्यां छागं हविर्वपां मेदः प्रस्थितं प्रेष्य ॥ प्रेष्य ॥ ६१ ॥**

(प्रदीपः) प्रेष्यब्रुवोः ॥ ६१ ॥ हविषोऽप्रस्थितस्येति । यदा प्रस्थितत्वेन हविर्विशेष्यते तदा षष्ठी न भवतीत्यर्थः ॥ ६१ ॥

(उद्द्योतः) प्रेष्यब्रुवोः ॥ ६१ ॥ हविषः प्रस्थानासंभवादाह—यदेति ॥ ६१ ॥

—

(३२९ षष्ठीसूत्रम् ॥ २ । ३ । ३ आ. ७ सू.)

५२० चतुर्थ्यर्थे बहुलं छन्दसि ॥ २।३।६२ ॥

(१५३५ वार्त्तिकम् ॥ १)

॥ * ॥ षष्ठ्यर्थे चतुर्थी ॥ * ॥

(भाष्यम्) **षष्ठ्यर्थे चतुर्थी वक्तव्या । या खर्वेण पिबति तस्यै खर्वो जायते यां मलवद्वाससं संभवन्ति यस्ततो जायते सोभिशस्तो, यामरण्ये तस्यै स्तेनो,**

यां पराचीं तस्यै ह्रीतमुख्यपगल्भो, या स्नाति तस्या अप्सु मारुको, याभ्यङ्क्ते तस्यै दुश्चर्मा, या प्रलिखते तस्यै खलतिरपमारी, याङ्क्ते तस्यै काणो, या दतो धावते तस्यै श्यावदन्, या नखानि निकृन्तते तस्यै कुनखी, या कृणत्ति तस्यै क्लीबो, या रज्जुं सृजति तस्या उद्बन्धुको, या पर्णेन पिबति तस्या उन्मादुको जायते, अहल्यायै जार मनाय्यै तन्तुः ॥

(प्रदीपः) चतुर्थ्यर्थे ॥ ६२ ॥ या खर्वेणेति । रजस्वलायाः खर्वपानादिनिषेधार्थोयमर्थवादः ॥

(उद्द्योतः) चतुर्थ्यर्थे ॥ ६२ ॥ खर्वेण । अग्निदग्धशरावेण । अञ्जलिरपक्वशरावो वा विहित इति बोध्यम् । खर्वो वामनः ॥ रजस्वलाप्रस्तावे तैत्तिरीयश्रुतौ न सहासीत नास्या अन्नमद्यादृक्ष्महत्यायै ह्येषा वर्णं प्रतिमुच्यास्तेथो खल्वाहुरभ्यञ्जनं वाव स्त्रिया अन्नमभ्यञ्जनमेव न प्रतिगृह्यं काममन्यदित्युपक्रम्य "यां मलवद्वाससमित्यादि ॥ मलवद्वाससं रजस्वलाम् संभवन्ति गर्भाधानार्थमुपगच्छन्ति । ततो जातोऽभिशस्तः मिथ्यारोपितपातकः ॥ अरण्ये इति । संभवतीत्यनुवर्तते । स्तेनश्चौरः । पराचीं लज्जादिना पराग्वलितवदनामन्यचित्तां वा । तस्या ह्रीतमुखी लज्जावनतवदनः तस्यैव व्याख्या अपगल्भः सप्रगल्भ इत्यर्थः ॥ मारुको मरणशीलः ॥ अभ्यङ्क्ते तैलादिनेति शेषः ॥ दुश्चर्मा कुष्ठी ॥ प्रलिखते चित्रादि लिखति । खलतिरकेशशिराः ॥ अपमारी अपमृत्युयुक्तः । अञ्जनं नेत्रयोः कज्जलदानम् ॥ श्यावदन् मलिनदन्तः ॥ या कृणत्ति औषध्यादीन् छिनत्ति । उद्बन्धुकः गले रज्जुं बद्ध्वा मरणशीलः ॥ उन्मादुकः उन्मत्तशीलः । एतदग्रे श्रुतौ या खर्वेण पिबति तस्यै खर्वस्तिस्रो रात्रीर्व्रतं चरेत् । अञ्जलिना वा पिबेदखर्वेण वा पात्रेण प्रजायै गोपीथायाहल्यायै जार मनाय्यै तन्तुरिति तस्मात्तिस्रो रात्रिर्व्रतं चरेत् । अहल्याया जारेत्यर्थेऽहल्यायै जारेत्यादि ॥६२॥

(आक्षेपभाष्यम्)

तर्त्तर्हि वक्तव्यम् ? ॥

(समाधानभाष्यम्)

न वक्तव्यम् ॥

(१५३६ वार्तिकम् २)

॥ * ॥ योगविभागासिद्धम् ॥ * ॥

(भाष्यम्) "चतुर्थी" । ततः "अर्थे बहुलं छन्दसि" ॥ चतुर्थ्य ॥ ६२ ॥

(प्रदीपः) चतुर्थीति । षष्ठीप्रकरणात् षष्ठ्यर्थे चतुर्थी भवतीत्येको वाक्यार्थः । चतुर्थ्यर्थे षष्ठीति द्वितीयः ॥ ६२ ॥

(२२० कारकषष्ठीसूत्रम् ॥ २ । ३ । ३ आ. ८)

५२३ कर्तृकर्मणोः कृति ॥ २।३।६५ ॥

(कृद्ग्रहणप्रयोजनाधिकरणम्)

(आक्षेपभाष्यम्)

कृद्ग्रहणं किमर्थम् ? ॥

(समाधानभाष्यम्)

इह मा भूत्—पचत्योदनं देवदत्त इति ॥

(१५३७ आक्षेपवार्तिकम् ॥ १)

॥ * ॥ कर्तृकर्मणोः षष्ठीविधाने कृद्ग्रहणानर्थक्यं लप्रतिषेधात् ॥ * ॥

(भाष्यम्) कर्तृकर्मणोः षष्ठीविधाने कृद्ग्रहणमनर्थकम् । किं कारणम्? । लप्रतिषेधात् । प्रतिषिध्यतेऽत्र षष्ठी 'लप्रयोगे न' इति ॥

(आक्षेपपरिहारभाष्यम्)

तस्य कर्मकर्त्रर्थं तर्हि कृद्ग्रहणं कर्तव्यम् । कृतो ये कर्तृकर्मणी तत्र यथा स्यादन्यस्य ये कर्तृकर्मणी तत्र मा भूदिति ॥

(प्रदीपः) कर्तृकर्मणोः ॥ ६५ ॥ तस्य कर्मकर्त्रर्थमिति । कर्तृकर्मविशेषणार्थं कृद्ग्रहणमित्यर्थः ॥

(परिहारबाधकभाष्यम्)

नैतदस्ति प्रयोजनम् । धातोर्हि द्वये प्रत्यया विधीयन्ते तिङश्च कृतश्च । तत्र कृत्प्रयोग इष्यते तिङ्प्रयोगे प्रतिषिध्यते ॥

(प्रदीपः) नैतदस्तीति ॥ यथोक्तप्रयोजनं कृद्ग्रहणमिह तावन्नोपयुज्यत इति दर्शयति ॥ पश्चादुत्तरत्रानुपयोगं दर्शयिष्यति । इह कर्तृकर्मसंनिधानात् क्रिया संनिधीयते क्रियाया हि कारकं भवति । सा च वाचकं धातुं प्रत्ययसहितमाक्षिपतीति मत्वाह—धातोर्हीति ॥

(उद्द्योतः) कर्तृकर्मणोः ॥६५॥ यथोक्तेति । तस्य कर्मकर्त्रर्थमित्यस्यात्रार्थान्तरं वक्तुं पूर्वोक्तार्थकत्वं निरस्यतीति भावः ॥ ननु कर्तृकर्मत्वे क्रियापेक्षे न धात्वपेक्षे, इति धातोरित्ययुक्तमत आह—इहेति ॥ वाचकं धातुमिति । न च स्ववाचकाक्षेपेऽपि धात्वाक्षेपे मानाभावः, खनतीत्याद्यर्थे जायमानानां तद्धितानामपि क्रियोपसर्जनद्रव्यवाचकत्वेन क्रियावाचकत्वात् । तदर्थाश्रयादिष्वपि कर्तृत्वादिप्रयुक्तकार्यदर्शनाच्च । अयमेव तस्य कर्मकर्त्रर्थमिति वक्तुराशय इति वाच्यम् । एतद्भाष्यप्रामाण्येन कारकान्वययोग्यक्रिया धातुवाच्यैव न तु तद्धितादिवाच्येति निर्णयेनादोषात् । देवदत्तेन शत्योऽश्व आश्विको भूमित्यादयोऽप्रयोगा एव । एवंच हिरुगादियोगे न द्वितीयादयः । न चाधिका खारी द्रोणेनेत्यनापत्तिः । तत्र प्रकृत्यादिस्वाद्धेतौ वा तृतीयायाः सत्त्वेनादोषादित्युपपत्ते निरूपयिष्यामः ॥

(परिहारसाधकभाष्यम्)

न ब्रूमः—इहार्थं तस्य कर्मकर्त्रर्थं कृद्ग्रहणं कर्तव्यमिति । किं तर्हि ? । उत्तरार्थम्—'अव्ययप्रयोगे न' इति षष्ठ्याः प्रतिषेधं वक्ष्यति, स कृतोऽव्ययस्य ये कर्तृकर्मणी तत्र यथा स्यात् । अकृतोऽव्ययस्य ये कर्तृकर्मणी तत्र मा भूद्—उच्चैः कटानां स्रष्टेति ॥

(प्रदीपः) तदेवं व्यावर्त्यासंभवादिहार्थं कृद्ग्रहणं कर्तृकर्मविशेषणार्थं नोपयुज्यत इति दर्शितम् । इदानीमुत्तरार्थत्वमाशङ्क्य निराकरोति—**न ब्रूम इति** । **न लोकाव्ययेत्य**त्राव्ययं कृद्ग्रहणेन विशेष्यते कृदव्ययस्य ये कर्तृकर्मणी तत्र षष्ठीप्रतिषेधो यथा स्यात् कटं कृत्वेत्यादौ । अकृतस्त्वव्ययस्य कर्तृकर्मणोः षष्ठीनिषेधो मा भूदुच्चैः कटानां स्रष्टेति ॥

(उद्योतः) भाष्ये—**अकृतोऽव्ययस्य ये इति** । अकृतोऽव्ययस्य प्रयोगे यत्किंचित्क्रियानिरूपिते ये कर्तृकर्मणी इत्यर्थः । सूत्रस्यापि अव्ययप्रयोगे नेत्येवार्थः ॥

(१५३८ आक्षेपसाधकवार्तिकम् ॥ २)

॥ * ॥ तस्य कर्मकर्त्रर्थमिति चेत्प्रतिषेधेपि तदन्तकर्मकर्तृत्वात्सिद्धम् ॥

(भाष्यम्) **कृत एते कर्तृकर्मणी नाव्ययस्य । अधिकरणमत्राव्ययम् ॥**

(प्रदीपः) **प्रतिषेध इति** । **न लोकाव्यये**ति सूत्रे अव्ययग्रहणेन कर्तृकर्मणी विशेष्येते—अव्ययस्य ये कर्तृकर्मणी तयोः षष्ठी न भवतीति । न च कृदन्ताव्ययादन्यस्याव्ययस्य कर्तृकर्मणी संभवत इति सामर्थ्यलभ्यं तत्रापि कृद्ग्रहणमित्यर्थः ॥ **कृत इति** । स्रष्टुरित्यस्य ॥ **नाव्ययस्येति** । उच्चैःशब्दस्येत्यर्थः । तस्याऽक्रियावाचकत्वात् । तदेवाह—**अधिकरणमिति** । उच्चैःस्थाने स्थितानां कटानां स्रष्टेत्यर्थः ॥

(उद्योतः) **तदन्तकर्मकर्तृत्वादिति** । कृदन्तकर्तृत्वकर्मत्वमेवैतयोर्न त्वव्ययकर्तृत्वकर्मत्वमेतयोरित्यर्थः । तदुपपादयति—**न लोकेति** ॥

(समाधानान्तरभाष्यम्)

इदं तर्हि प्रयोजनम्—उभयप्राप्तौ कर्मणि षष्ठ्याः प्रतिषेधं वक्ष्यति, स कृतो ये कर्तृकर्मणी तत्र यथा स्यात् । कृतो ये कर्तृकर्मणी तत्र मा भूदिति । आश्चर्यमिदं वृत्तमोदनस्य च नाम पाको ब्राह्मणानां च प्रादुर्भाव इति ॥

(प्रदीपः) **कृतो ये इति** । एकस्यैव कृतो न तु भिन्नयोः कृतोरित्यर्थः । कृद्ग्रहणे क्रियमाणे शब्दप्रतिपादितत्वादन्यपदार्थस्योभयप्राप्ताविति बहुव्रीहिर्लभ्यते । अन्यथान्तरङ्गत्वात्तत्पुरुषः स्यात् ॥

(उद्योतः) **अन्ययेति** । सन्देहे तत्पुरुषस्यैव न्याय्यत्वम् । कृत्पदोपादाने तु अन्यपदार्थस्य स्पष्टत्वाद्बहुव्रीहिरेवेति भावः ॥ भाष्ये—प्रतिषेधशब्दो नियमशास्त्राणां निषेधे पर्यवसानमभिप्रेत्येत्याहुः ॥

(आक्षेपभाष्यम्)

अथ क्रियमाणेपि कृद्ग्रहणे कस्मादेवात्र न भवति ? ॥

(प्रदीपः) **अथेति** । कृतीत्येकत्वस्याविवक्षायां जातिविवक्षायां वा तत्पुरुषं च मत्वा चोदयति ॥

(उद्योतः) **एकत्वस्याविवक्षायामिति** । उद्देश्यनिमित्तगतत्वादिति भावः ॥

(समाधानभाष्यम्)

'उभयप्राप्तौ' इति नैवं विज्ञायते—उभयोः प्राप्तिरुभयप्राप्तिः उभयप्राप्ताविति ॥ कथं तर्हि? । उभयोः प्राप्तिर्यस्मिन्कृति सोयमुभयप्राप्तिः कृद् उभयप्राप्ताविति ॥

(प्रदीपः) कृत्यन्यपदार्थे बहुव्रीहिराश्रीयत इति परिहारः । तेनाश्चर्यो गवां दोहो गोपालकेनेत्यादावेव नियमः प्रवर्तते ॥

(सिद्धान्तसमाधानभाष्यम्)

अथ वा कृतो ये कर्तृकर्मणी तत्र यथा स्यात् । तद्धितस्य ये कर्तृकर्मणी तत्र मा भूदिति । कृतपूर्वी कटं भुक्तपूर्वी ओदनमिति ॥

(प्रदीपः) यद्येवमुत्तरत्रैव कृद्ग्रहणं कर्तव्यम्, अथ वा व्याख्यानाद् बहुव्रीहिराश्रयिष्यते इत्याशङ्क्याह—**अथ वेति** ॥ **कृतपूर्वीति** । कृतं पूर्वमनेनेति सुप्सुपेति समासः । **पूर्वादिनिःसपूर्वाच्चेती**निप्रत्ययः । कर्तात्र तद्धितेनोक्त इति ततः षष्ठीप्रसङ्गाभावः । कटात्तु कर्मणः षष्ठी मा भूदित्येवमर्थं कृद्ग्रहणम् ॥

(उद्योतः) भाष्ये—**कृतो ये इति** ॥ कृदन्तशक्तिग्रहसहकारेणोपलक्षितायाः क्रियाया ये इत्यर्थः ॥ **तद्धितस्येति** । तद्धितान्तशक्तिग्रहसहकारेणोपलक्षितक्रियाया ये इत्यर्थः ॥

(आक्षेपभाष्यम्)

ननु च वाक्येनैवानेन न भवितव्यम् ॥

तत्र द्वितीयया तावन्न भवितव्यम् । किं कारणम् ? । केनाभिहितं कर्मेति कृत्वा ॥

इनिप्रत्ययेन चापि नोत्पत्तव्यम् । किं कारणम्? । असामर्थ्यात् ॥ कथमसामर्थ्यम् ? । सापेक्षमसमर्थं भवतीति ॥

(प्रदीपः) **ननु चेति** । कृतपूर्वी कटमित्यनेनेत्यर्थः ॥ **द्वितीययेति** । तस्याश्चाप्राप्तौ तदपवादः षष्ठ्यपि न प्राप्नोति इहाप्यनभिहिताधिकारात् ॥ **सापेक्षमिति** । कृतः पूर्वं

कटोऽनेनेति विवक्षायां कटापेक्षत्वात् तद्धितेन न भाव्यमित्यर्थः ॥

(उद्द्योतः) एतद्वाक्यभवनाभावे हेतुमाह—तत्र द्वितीयेति ॥ कटापेक्षत्वादिति । कृत इत्यस्य विशेष्यतया कटसापेक्षत्वादित्यर्थः । अन्यथा क्रियायाः कारकांशे नित्यसापेक्षतयाऽसंगतिः स्पष्टैवेति बोध्यम् ॥ नित्यसापेक्षस्थलेऽपि क्वचिदेव समासो न सर्वत्रेत्याशयमन्ये ॥

(आक्षेपपरिहारभाष्यम्)

यत्तावदुच्यते—'द्वितीयया तावन्न भवितव्यम्। किं कारणम्?। केनाभिहितं कर्मेति कृत्वेति' ॥ योसौ कृतकटयोरभिसंबन्धः स उत्पन्ने प्रत्यये निवर्तते। अस्ति च करोतेः कटेन सामर्थ्यमिति कृत्वा द्वितीया भविष्यति ॥

यदप्युच्यते—'इनिप्रत्ययेन चापि नोत्पत्तव्यम्। किं कारणम्?। असामर्थ्यात्। कथमसामर्थ्यम्?। सापेक्षमसमर्थं भवतीति' ॥ नेदमुभयं युगपद्भवति वाक्यं च प्रत्ययश्च। यदा वाक्यम्, न तदा प्रत्ययः। यदा प्रत्ययः, सामान्येन तदा वृत्तिः। तत्रावश्यं विशेषार्थिना विशेषोनुप्रयोक्तव्यः—कृतपूर्वी किम्?। कटम्। भुक्तपूर्वी किम्?। ओदनमिति ॥

(प्रदीपः) **योसाविति** । कृतः कटोऽनेनेति वाक्ये कृतकटयोः सामानाधिकरण्यम् । अस्मिंश्चार्थविशेषे न भाव्यं वृत्त्या । तस्याः सामान्यविषयत्वात् ॥ तस्मात्कर्मसामान्ये भावे वा क्त उत्पद्यते । तत्र कृतं पूर्वमनेनेत्यस्मिन्नर्थे कृतपूर्वीशब्दो वर्तते तेन पूर्वं कृतवानित्यर्थः संपद्यते । तत्र करोतिवाच्यक्रियापेक्षमस्ति कटस्य कर्मत्वम् । तथाह हरिः—

> **विशेषकर्मसंबन्धे निर्भुक्तेऽपि कृतादिभिः ।**
> **विशेषनिरपेक्षोन्यः कृतशब्दः प्रवर्तते ॥**
> **अकर्मकत्वात् सत्येवं क्तान्ते भावाभिधायिनि ।**
> **ततः क्रियावता कर्त्रा योगो भवति कर्मणाम् ॥**
> **अविग्रहा गतादिस्था यथा ग्रामादिकर्मभिः ।**
> **क्रिया संबध्यते तद्वत् कृतपूर्व्यादिषु स्थितेति ॥**

(उद्द्योतः) भाष्ये—**योऽसौ कृतकटयोरिति** । यः कृतकटयोः सामानाधिकरण्यरूपसम्बन्धो वाक्ये दृष्टः स उत्पन्ने प्रत्यय इनौ **निवर्तते** निवृत्त इति बुद्धिविषयो भवति, भावविषयकृतशब्देन वृत्तिसत्त्वात्तत्रान्यार्थदर्शनात्तद्धितार्थैकार्थीभूतस्य कृतस्य कटेन सम्बन्धाभावादिति भावः ॥ ननु विशेषातिरिक्तसामान्यसद्भावे मानाभावात्कृधात्वर्थफलाश्रयः केनाभिहित इति ज्ञानकाले तदर्थफलेऽन्वितस्य कटस्यानभिहिततया वक्तुमशक्यत्वाच्च **कर्मसामान्ये** इत्यसंगतमत आह—**भावे वेति** । अविवक्षितकर्मतया अकर्मकत्वम् । फलांशे प्रागाश्रयविशेषान्वयाविवक्षैवात्र कर्माविवक्षेत्याहुः ॥ **कृतं पूर्वमनेनेति** । अर्थप्रदर्शनमात्रमेतत् नत्वयं प्रयोगः साधुः । प्रत्ययोत्पत्त्यनन्तरं भाष्ये सामानाधिकरण्यनिवृत्त्युक्तेर्वाक्ये 'कृतकटयोः सामानाधिकरण्येन प्रयोगस्यैव साधुत्वात् ॥ **कर्मत्वमिति** । अस्त्यनभिहितं कटस्य कर्मत्वमित्यर्थः ॥ **विशेषकर्मेति** । कृतः कटोऽनेनेत्यस्यामवस्थायां कृतशब्देन विशेषकर्मकटादिसम्बन्धे निर्भुक्तेऽपि अनुभूतेऽपि तस्यामवस्थायामसामर्थ्येन वृत्तिविरहाद् । **विशेषनिरपेक्षो** भाववचनोऽन्य एव **कृतशब्दः प्रवर्तते** वृत्तिं लभत इत्यर्थः ॥ तदेवोपपादयन्नविवक्षितकर्मतया भावे क्त इत्याह—**अकर्मकत्वादिति** । एवं विशेषनिरपेक्षत्वे विशेषरहितसामान्यस्याभावादित्यर्थः । अत्र **क्तान्तं भावाभिधायि** तदिति क्वचित्पाठः सुयुक्ततरः ॥ सप्तम्यन्तपाठे **भावाभिधायिनि** सति समासे तद्धितोत्पत्तिरिति शेषः ॥ एवं सति तद्धितोत्पत्तौ यथाऽसामर्थ्यं न भवति तथा दर्शयति—**ततः क्रियावतेति** । **कर्मणां** कटादीनां क्रियावत्कर्त्रर्थकेनिना तदन्तोपस्थाप्यक्रियया योगो भवतीत्यर्थः ॥ तत्रोपपत्तिमाह—**अविग्रहेति** । विशिष्य प्राधान्येन ग्रहो ग्रहणं तद्रहिताऽप्राधान्येन गृह्यमाणापीत्यर्थः। गुणभूतक्रिययापि कारकाणां सम्बन्धदर्शनादिति भावः ॥ तदुक्तं भाष्ये—**अस्ति च करोतेः कटेन सामर्थ्यमिति ॥ सामान्येन तदावृत्तिरिति** । अविवक्षितकर्मतया धात्वर्थमात्रवृत्तिना भावक्तान्तेनेत्यर्थः ॥ **विशेषार्थिनेति** । कर्मविशेषजिज्ञासानिवर्तकयत्नवतेत्यर्थः ॥ एषा च विवक्षा प्रयोगानुसारात्क्वचिदेव । तेन घटं क्रियते घटं कृतमित्यादि नापादनीयम् ॥ कृद्ग्रहणे कृते तु न दोषः । कर्मणः कृदन्तमात्रोपस्थाप्यक्रियान्वयाभावात् । स चास्योक्तरीत्या न क्वापि पृथक् प्रयोग इति तन्मात्रस्य शक्तिग्रहाभावात् । अत एव तण्डुलानां पाचकपुत्रः पाचकतर इत्यादौ न दोषः । निषेधसूत्रेऽपि ल्वादिसाहचर्यान्निष्ठांशेपि तथार्थ इति न निषेधप्रवृत्तिः । कटं कृतं पाचकपुत्र इत्यादौ च निषेधप्रवृत्तिः । अत एव भाष्ये—**करोतेः कटेन सामर्थ्यमि**त्युक्तं न तु कृतशब्दस्य कटेनेत्युक्तम् । एवं च सकर्मकधातावीदृशविवक्षाया भावे क्तप्रत्यय ईदृशसमासविषय एव नान्यत्रेति भाष्यस्वरसाल्लभ्यते ॥ ग्रान्तं देशमित्यादौ तु **गत्यर्थाकर्मकेति** भावे क्तो बोध्यः ॥

(समाधानान्तरभाष्यम्)

अथ वा इदं प्रयोजनम्—कर्तृभूतपूर्वमात्रादपि षष्ठी यथा स्यात्—भेदिका देवदत्तस्य यज्ञदत्तस्य काष्ठानामिति ॥ कर्तृक० ॥ ६५ ॥

(प्रदीपः) **कर्तृभूतपूर्वमात्रादिति** । करोतीति कृदिति कर्ताभिधीयते तत्र कर्तरि पुनः षष्ठीविधानाद् गुणभूतेऽपि भवति । एवं तु तद्धितनिवृत्तिर्न कृता स्यात् ॥ **भेदिकेति** । भिदेर्ण्यन्तात्पर्यायादिषु ण्वुच् । अत्र प्रयोजकः कर्ता ण्यर्थस्य प्राधान्यात् प्रधानम् । प्रयोज्यकर्ता तु प्रकृत्यर्थस्याप्राधान्यादप्रधानम् । तत्र प्रधानाप्रधानसंनिधौ प्रधानादेव षष्ठी स्याद् नाप्रधानात्, कृद्ग्रहणात् तु भवति ॥ अथ कर्तृभूतपूर्वा-

दिति कथमुच्यते। नहि प्रयोजकसन्निधौ प्रयोज्यस्यकर्तृत्वमपैति। गत्यादिसूत्रनियमात् कर्मत्वाभावात् कर्तृत्वस्यैवावस्थानात् १। एवं तर्हि प्राधान्यस्यात्र भूतपूर्वत्वं विवक्षितम् । प्रधानचरात् कर्तुरित्यर्थः । एतच्च विशेषापेक्षायां प्रयोजनमुक्तम् । यदा तृतीयावत् कर्तृमात्रे षष्ठीत्याश्रीयते तदा भिन्नशब्दवाच्ययोः प्रधानाप्रधानयोः कर्त्रोरेकशब्दवाच्यताया अभावाद्विरोधाभावात् षष्ठी सिध्यतीति नेदं कृद्ग्रहणस्य प्रयोजनम् । तद्धितनिवृत्तिस्तु प्रयोजनमेव ॥ ६५ ॥

(उद्योतः) एतच्च विशेषापेक्षायामिति । अत्रैव प्रधानन्यायो न तृतीयादिविधाविति विशेषापेक्षायामित्यर्थः ॥ विरोधाभावे हेतुरेकशब्दवाच्यत्वाभावः । तदुपपादकं भिन्नशब्दवाच्ययोरित्यादीति बोध्यम् ॥ ६५ ॥

(३३१ नियमसूत्रम् ॥ २ । ३ । ३ आ. ९)

५२४ उभयप्राप्तौ कर्मणि ॥ २।३।६६ ॥

(नियमप्रतिषेधाधिकरणम्)

(१५३९ प्रतिप्रसववार्तिकम् ॥ १)

॥ * ॥ उभयप्राप्तौ कर्मणि षष्ठ्याः प्रतिषेधेऽकादिप्रयोगेऽप्रतिषेधः ॥ * ॥

(भाष्यम्) उभयप्राप्तौ कर्मणिषष्ठ्याः प्रतिषेधेऽकादिप्रयोगे प्रतिषेधो न भवतीति वक्तव्यम् । भेदिका देवदत्तस्य काष्ठानाम्; चिकीर्षा विष्णुमित्रस्य कटस्य ॥

(प्रदीपः) उभय ॥ ६६ ॥ षष्ठ्याः प्रतिषेध इति । नियमेनानेन कर्तुः षष्ठी प्रतिषिध्यत इत्यभिप्रेत्यैतदुक्तम् ॥ भेदिकेति । पर्यायादौ ण्वुच् ॥

(उद्योतः) उभयप्राप्तौ ॥ ६६ ॥ नियमेनानेनेति । नियमशास्त्राणां निषेधे तात्पर्यादन्यथानुवादवैयर्थ्यापत्तिरिति भावः ॥

(भाष्यम्) अपर आह—

(१५४० वार्तिकन्यासान्तरम् ॥ २)

॥ * ॥ अकाकारयोः प्रयोगे प्रतिषेधो नेति वक्तव्यम् ॥ * ॥

(१५४१ वार्तिकम् ॥ ३)

॥ * ॥ शेषे विभाषा ॥ * ॥

(भाष्यम्) शोभना खलु पाणिनेः सूत्रस्य कृतिः, शोभना खलु पाणिनिना सूत्रस्य कृतिः । शोभना खलु दाक्षायणस्य संग्रहस्य कृतिः, शोभना खलु दाक्षायणेन संग्रहस्य कृतिः ॥ उभय० ॥ ६६ ॥

(प्रदीपः) शेषे विभाषेति । अकाकारव्यतिरिक्तस्त्रीप्रत्यय एव नान्यस्मिन्निति केचिदाहुः ॥ अपरे तु प्रत्ययमात्रेऽकाकारवर्जिते विकल्पमिच्छन्ति । शब्दानामनुशासनमाचार्यस्याचार्येणेति वा ॥ ६६ ॥

(उद्योतः) स्त्रीप्रत्ययएवेति । भाष्ये अकाकारयोर्भेदिका चिकीर्षेति, कृतिरिति च स्त्रीप्रत्यये एवोदाहरणदानादिति तदाशयः ॥ अपरे त्विति । नोदाहरणमादरणीयमिति तद्भावः ॥६६॥

(३३२ कारकषष्ठीसूत्रम् ॥ २ । ३ । ३ आ. १०)

५२५ क्तस्य च वर्तमाने ॥ २।३।६७ ॥

(विशेषविवक्षाधिकरणम्)

(१५४२ शेषपूरकवार्तिकम् ॥ १)

॥ * ॥ क्तस्य च वर्तमाने नपुंसके भाव उपसंख्यानम् ॥ * ॥

(भाष्यम्) क्तस्य च वर्तमाने नपुंसके भाव उपसंख्यानं कर्तव्यम् । छात्रस्य हसितम्, नटस्य भुक्तम्, मयूरस्य नृत्तम्, कोकिलस्य व्याहृतमिति ॥

(प्रदीपः) क्तस्य च ॥ ६७ ॥ छात्रस्य हसितमिति । हासो हसितमिति नपुंसके भावे क्तः । तत्र च्छात्रस्य कर्तृत्वात् तृतीयाप्रसङ्गे षष्ठीविधानार्थं वचनम् ॥

(उद्योतः) क्तस्य च ॥ ६७ ॥ नपुंसके भाव इति । इदं वार्तिकं लक्षणप्रतिपदोक्तपरिभाषया कालोदासीननपुंसके भावे क्त इतिसूत्रविहितक्तयोग एव । तेन भूते भावे क्तेन योगे तृतीयैवेति वार्त्तिकमतम् । यद्यपि शेषत्वविवक्षयापि सिद्धं तथाऽपि कर्तृत्वप्रकारके बोधे षष्ठ्यर्थमिदमिति वार्त्तिकाशयः । भाष्यकारस्तु तादृश एवार्थे साधुत्वमङ्गीकृत्य प्रत्याचख्यौ ॥

(तृतीयाक्षेपभाष्यम्)

[तत्तर्हि वक्तव्यम्? ॥

(समाधानभाष्यम्)

न वक्तव्यम् ॥]

(१५४३ अन्यथासिद्धिवार्तिकम् ॥ २)

॥ * ॥ शेषविज्ञानात्सिद्धम् ॥ * ॥

(भाष्यम्) शेषलक्षणात्र षष्ठी भविष्यति ॥ शेष इत्युच्यते । कः शेषः? । कर्मादीनामविवक्षा शेषः ॥ कथं पुनः सतो नामाविवक्षा स्यात्, यदा छात्रो हसति, नटो भुङ्क्ते, मयूरो नृत्यति, कोकिलो व्याहरति? ॥ सतोऽप्यविवक्षा भवति । तद्यथा—अलोमिका एडका' 'अनुदरा कन्येति । असतश्च विवक्षा—समुद्रः कुण्डिका' 'विन्ध्यो वर्धितकमिति ॥

(प्रदीपः) **शेषश्च क इति**। कर्तृत्वसद्भावान्नास्ति शेषत्वमिति प्रश्नः॥ **कर्मादीनामिति**। सदपि च्छात्रस्य कर्तृत्वमविवक्षयाऽपाक्रियते। संबन्धित्वमात्रं ह्यत्र विवक्षितम्। छात्रस्य संबन्धि हसितमित्यर्थः॥

(आक्षेपभाष्यम्)

यद्येवम्, उत्तरत्र चातुःशब्द्यं प्राप्नोति—इदमहेः सृप्तम्, इहाहिना सृप्तम्, इहाहिः सृप्तः, इहाहेः सृप्तम् ग्रामस्य पार्श्वे ग्रामस्य मध्ये इति॥

(प्रदीपः) **उत्तरत्रेति**। **अधिकरणवाचिनश्चेत्यत्र**॥ **इदमिति**। अत्राधिकरणे क्तः॥ तेनाभिहितमधिकरणमिति इदंशब्दात्प्रथमा कृता, अहिशब्दात्त्वधिकरणवाचिनश्चेति षष्ठी॥ **इहाहिना सृप्तमिति**। अत्र भावे क्तः॥ **इहाहिः सृप्त इति**। अत्र कर्तरि क्तः॥ **इहाहेः सृप्तमिति**। भाव एव क्तः। तत्र शेषविवक्षायां षष्ठी स्यादिति चोद्यम्॥

(उद्द्योतः) भाष्ये—यद्येवमिति। एवं शेषत्वविवक्षया षष्ठ्यङ्गीकारे॥ अधिकरणवाचिनश्चेत्यत्रेति। एतत्सूत्रोदाहरणविषयीभूतगत्यर्थे इत्यर्थः। तत्र हि क्तोऽधिकरणे च ध्रौव्यगति इति विशेषविधानान्नपुंसके भावे क्त इत्यस्याप्रवृत्तिरेवेति वार्त्तिकमते वार्त्तिकेन षष्ठी न प्राप्नोति। शेषत्वविवक्षायाश्च भावविषयेऽभाव एवेति वार्त्तिकमते त्रैशब्द्यम्। प्रत्याख्यातृमते च शेषे षष्ठी स्यादिति चातुःशब्द्यमित्यर्थः। तदाह—तत्र शेषेति। कर्माविवक्षयाऽकर्मकत्वे इमानि चत्वारि रूपाणि, सकर्मकत्वे तु अहिना सृप्तो ग्राम इति पञ्चममपि बोध्यमिति केचित्॥

(इष्टापत्तिभाष्यम्)

इष्यत एव चातुःशब्द्यम्॥ क्तस्य च॥ ६७॥

(प्रदीपः) **इष्यत एवेति**। परिहारः। **ग्रामस्य पार्श्वे इति** सप्तमीप्रयोगेण नायमधिकरणे क्तः कृतः, किं तर्हि भाव इति दर्शयति॥ ६७॥

(उद्द्योतः) सप्तमीप्रयोगेणेति। इहेति सप्तमीप्रयोगेणैवेदं दर्शितम्। इहपदार्थस्यैव चेदं विवरणं भाष्ये इति बोध्यम्॥ **किं तर्हि भाव इति**। इदमिहाहिः सृप्त इत्युदाहरणे, कर्तरीत्यस्योपलक्षणम्॥ ६७॥

(३३३ कारकषष्ठीनिषेधसूत्रम्॥२।३।३ आ. ११)

५२७ न लोकाव्ययनिष्ठाखलर्थतृनाम्॥ २।३।६९॥

(इष्टोपपादकाधिकरणम्)

(१५४४ विशेषवार्त्तिकप्रथमखण्डम्॥ १॥)

॥ * ॥ लादेशे सल्लिङ्ग्रहणं किकिनोः प्रतिषेधार्थम्॥ * ॥

(भाष्यम्) **लादेशे सल्लिङ्ग्रहणं कर्तव्यम्। सलिटोः प्रयोगे नेति वक्तव्यम्॥ किं प्रयोजनम्?। किकिनोः प्रतिषेधार्थम्। किकिनोरपि प्रयोगे प्रतिषेधो यथा स्यात्—पपिः सोमम्, ददिर्गाः॥**

किं पुनः कारणं न सिध्यति?॥

(१५४५ साधकवार्त्तिकद्वितीयखण्डम्॥ २॥)

॥ * ॥ तयोरलादेशत्वात्॥ * ॥

(भाष्यम्) **न हि तौ लादेशौ॥**

(प्रदीपः) न लोका०॥ ६९॥ **लादेश इति**। लग्रहणमपनीय सल्लिङ्ग्रहणं कर्तव्यम्। तत्र सद्ग्रहणेन शतृशानचौ गृह्येते। लिङ्ग्रहणेन च कानच्क्वसू लिट्संज्ञाविधानात् किकिनौ च। लग्रहणे तु किकिनोरलादेशत्वाद्ग्रहणाप्रसङ्गः॥

(उद्द्योतः) न लोकाव्यय॥ ६९॥ **अपनीयेति**। सल्लिङ्ग्रहणे तस्य फलाभावादित्यर्थः। लग्रहणेनैव सत्कानच्क्वसूनां सिद्धत्वात्किं सल्लिङ्ग्रहणेनेत्यत आह—**किकिनौ चेति**। लत्वस्य लादेशयोग इत्येवार्थः। लयोग इति तु न शक्यम्। आदेशे लत्वस्याल्विधित्वेन स्थानिवत्त्वायोगात्॥

(आक्षेपभाष्यम्)

अथ तौ लादेशौ स्याताम्। स्यात्प्रतिषेधः?॥

(प्रदीपः) **अथ तद्विति**। लिट्कार्यातिदेशाल्लादेशतुल्यावित्यर्थो विवक्षितः॥

(उद्द्योतः) लिट्कार्यातिदेशादिति। द्वित्वविधानेनैव सिद्धौ तद्वदतिदेशाल्लिडादेशतुल्यावित्यर्थ इति भावः॥

(समाधानभाष्यम्)

बाढं स्यात्॥

(प्रदीपः) परस्तु यथोक्तमभिप्रायमप्रतिपद्य लादेशत्वमेवानयोर्विप्रतिपन्नमिति मत्वाह—**बाढं स्यादिति**॥

(लादेशत्वसाधकभाष्यम्)

लादेशौ तर्हि भविष्यतः॥ कथम्?। "आदृगमहनजनः किकिनौ लिट् च" इति लिड्वदिति वक्ष्यामि॥

(प्रदीपः) **वक्ष्यामीति**। व्याख्यास्यामीत्यर्थः॥

(उद्द्योतः) व्याख्यास्यामीति। संज्ञां न व्याख्यास्यामि किं त्वतिदेशं व्याख्यास्यामीत्यर्थः॥

(आक्षेपभाष्यम्)

स तर्हि वतिनिर्देशः कर्तव्यः। नह्यन्तरेण वतिमतिदेशो गम्यते॥

(प्रदीपः) परस्त्वपूर्वो वतिनिर्देशः कर्तव्यत्वेनानेन चोदित इति मत्वाह—**स तर्हीति**। विशेषातिदेशे च सामान्यातिदेशः प्रवर्तत एव। विशेषस्य सामान्याव्यभिचारात्। तेन लमात्रनिबन्धनः षष्ठीप्रतिषेधः किकिनोः प्रवर्तते तदत्र लिट्संज्ञा किकिनोर्विधीयत इति मत्वा वार्त्तिकारम्भः॥

(उद्द्योतः) ननु लिड्वदतिदेशेऽपि कथं लमात्राश्रयषष्ठीनिषेधोऽत आह—विशेषेति । संज्ञाप्रकरणाभावादिति मरवेस्युक्तम् ॥

(समाधानभाष्यम्)

अन्तरेणापि वतिमतिदेशो गम्यते । तद्यथा—'एष ब्रह्मदत्तः' अब्रह्मदत्तं ब्रह्मदत्त इत्याह, ते मन्यामहे—ब्रह्मदत्तवदयं भवतीति । एवमिहाप्यलिटं लिडित्याह लिड्वदिति ज्ञास्यते ॥

(प्रदीपः) कार्यातिदेशाश्रयेण तत्प्रत्याख्यानम् ॥

(१५४६ शेषपूरकवार्तिकम् ॥ ३ ॥)

[॥ * ॥ उकारप्रयोगे न ॥ * ॥]

(भाष्यम्) उकारप्रयोगे नेति वक्तव्यम् । कटं चिकीर्षुः, ओदनं बुभुक्षुः ॥

(प्रदीपः) उकारप्रयोग इति । उकारान्तप्रत्ययप्रयोगे इत्यर्थः । उप्रत्ययोपि चान्तवद्भावाद् गृह्यते ॥

(उद्द्योतः) भाष्ये—उकारेति । कारप्रयोगेण वर्णग्रहणमिति ध्वनितम् । तत्फलमाह—उकारान्तेति । शब्दरूपं विशेष्यमादाय तदन्तविधिः । स च प्रत्यय एव साहचर्यादिति भावः ॥ तेन कन्यामलङ्करिष्णुरित्यादि सिद्धम् । प्रत्ययाप्रत्यययोरिति तु वर्णग्रहणे न प्रवर्त्तत इति बोध्यम् ॥

(आक्षेपभाष्यम्)

तत्तर्हि वक्तव्यम्? ॥

(समाधानभाष्यम्)

न वक्तव्यम् । उकारोप्यत्र निर्दिश्यते ॥ कथम्? । प्रश्लिष्टनिर्देशोयम्—उ उक ऊक, ल ऊक लोकेति ॥

(प्रदीपः) उकारोपीति । उश्चोकश्चेति द्वयोर्द्वन्द्वः पूर्वं क्रियते ततोन्येषाम् । अन्यथा लवुकेति स्यात् ॥

(१५४७ प्रतिप्रसववार्तिकम् ॥ ४ ॥)

॥ * ॥ उकप्रतिषेधे कमेर्भाषायामप्रतिषेधः ॥ * ॥

(भाष्यम्) उकप्रतिषेधे कमेर्भाषायां प्रतिषेधो न भवतीति वक्तव्यम् । दास्याः कामुकः, वृषल्याः कामुकः ॥

(१५४८ प्रतिप्रसववार्तिकम् ॥ ५ ॥)

॥ * ॥ अव्ययप्रतिषेधे तोसुन्कसुनोरप्रतिषेधः ॥ * ॥

(भाष्यम्) अव्ययप्रतिषेधे तोसुन्कसुनोः प्रतिषेधो न भवतीति वक्तव्यम् । पुरा सूर्यस्योदेतोराधेयः । पुरा वत्सानामपाकर्तोः । पुरा क्रूरस्य विसृपो विरप्शिन् ॥

(१५४९ शेषपूरकवार्तिकम् ॥ ६ ॥)

॥ * ॥ शानंश्चानश्शतॄणामुपसंख्यानम् ॥ * ॥

(भाष्यम्) शानश्चानश्शतॄणामुपसंख्यानं कर्तव्यम् । सोमं पवमानः । नटमाघ्नानः । अधीयन् पारायणम् । लप्रयोगे नेति निषेधो न प्राप्नोति ॥

(प्रदीपः) लप्रयोगे 'नेति । एतेषां च अलादेशत्वात् ॥ ६९ ॥

(उद्द्योतः) एतेषां चेति । पूङ्यजोः शानन्नित्यादीनामित्यर्थः ॥

(वार्तिकवैयर्थ्यभाष्यम्)

मा भूदेवम् । तृन्नित्येवं भविष्यति ॥ कथम्? । तृन्निति नेदं प्रत्ययग्रहणम् ॥ किं तर्हि? । प्रत्याहारग्रहणम् ॥ क संनिविष्टानां प्रत्याहारः? । "लटः शतृ-" इत्यतः प्रभृत्या तृनो नकारात् ॥

(आक्षेपभाष्यम्)

यदि प्रत्याहारग्रहणम्, 'चोरस्य द्विषन्' अत्रापि प्राप्नोति ॥

(१५५० समाधानवार्तिकम् ॥ ७ ॥)

॥ * ॥ द्विषः शतुर्वावचनम् ॥ * ॥

(भाष्यम्) द्विषःशतुर्वेति वक्तव्यम् ॥ तच्चावश्यं वक्तव्यम् । प्रत्ययग्रहणे सति प्रतिषेधार्थम् । प्रत्याहारग्रहणे सति तदेव विध्यर्थं भविष्यति ॥ न लोकाव्य ॥ ६९ ॥

(उद्द्योतः) भाष्ये—प्रतिषेधार्थमिति । षष्ठ्याः सिद्धत्वेन प्रतिषेधमात्रफलकं वार्तिकमिति भावः ॥ तदेव विध्यर्थमिति ॥ नित्यं प्रतिषेधे प्राप्ते पक्षे षष्ठीविध्यर्थमित्यर्थः ॥ ६९ ॥

(३३४ कारकषष्ठीनिषेधसूत्रम् ॥ २ । ३ । ३ आ. १२)

५२८ अकेनोर्भविष्यदाधमर्ण्ययोः ॥ २।३।७० ॥

(अर्थप्रत्यययोरन्वयदर्शकाधिकरणम्)

(१५५१ वार्तिकम् ॥ १ ॥)

॥ * ॥ अकस्य भविष्यति ॥ * ॥

(भाष्यम्) अकस्य भविष्यतीति वक्तव्यम् । यवान् लावको व्रजति । ओदनं भोजको व्रजति ॥

(प्रदीपः) अकेनोः ॥ ७० ॥ यथासंख्यापवादार्थं वचनम्—अकस्येति ॥ स्वरितत्वाप्रतिज्ञानाद्यथासंख्याभावव्याख्यानं चेदमित्याहुः । अकस्य त्वाधमर्ण्ये नास्ति विधानमिति भविष्यदधिकारविहितस्यैव तस्य ग्रहणम् ॥

(उद्द्योतः) अकेनो ॥ ७० ॥ स्वरितत्वेति। यथासंख्यसूत्रे स्वरितेनेत्यनुवृत्तेरिति भावः। भविष्यदधिकारेति। इदं च तुमुन्ण्वुलाविलत्र भाष्ये स्पष्टम्॥ भविष्यदर्थकस्यापि ग्रहणमिति पक्षान्तरमपि तत्र स्पष्टम्॥ ७० ॥

(१५५२ वार्तिकम्॥ २॥)

॥ * ॥ इन आधमर्ण्ये च ॥ * ॥

(भाष्यम्) तत इन आधमर्ण्ये भविष्यति चेति वक्तव्यम्। शतं दायी सहस्रं दायी ग्रामं गमी॥ अके ॥ ७० ॥

(प्रदीपः) शतंदायीति। आवश्यकाधमर्ण्ययोर्णिनिरिति णिनिः॥ ग्रामंगमीति। भविष्यति गम्यादय इति वचनाद्भविष्यति गमेरिनिः। गत्यर्थकर्मणीत्यत्र चतुर्थी वेत्येव पक्षे द्वितीयायां सिद्धायां द्वितीयाग्रहणमपवादविषयेपि विधानार्थं ग्रामं गन्तेति यत् कैश्चिदुक्तं तद्भाष्यकारस्य नाभिमतमिति ग्रामंगमीत्युदाहरणोपपत्तिः॥ ७० ॥

(३३५ षष्ठीविकल्पनसूत्रम्॥ २। ३। ३ आ. १३)

५२९ कृत्यानां कर्तरि वा ॥ २।३।७१॥

(योगविभागाधिकरणम्)

(आक्षेपभाष्यम्)

कर्तृग्रहणं किमर्थम्?॥

(समाधानभाष्यम्)

कर्मणि मा भूदिति॥

(समाधानबाधकभाष्यम्)

नैतदस्ति प्रयोजनम्। भावकर्मणोः कृत्या विधीयन्ते। तत्र कृत्यैरभिहितत्वात्कर्मणि षष्ठी न भविष्यति॥

(उद्द्योतः) कृत्यानाम्॥ ७१॥ भाष्ये—भावकर्मणोरिति। तत्र भावेऽकर्मकाद्विधानेन कर्मणोऽभाव एव, कर्मणि तु सकर्मकाद्विधानेऽपि तस्याभिधानमेवेति भावः। न च कर्तव्यपूर्वी कटमित्यादौ अविवक्षितकर्मतया भावे तव्ये पश्चात्कर्मसन्निधाने भावेपि संभव इति वाच्यम्। भाष्यप्रामाण्येन कृत्यविषये तथा विवक्षाया अभावादित्याहुः॥

(समाधानभाष्यम्)

अत उत्तरं पठति—

(१५५३ वार्तिकम्॥ ३॥)

॥ * ॥ भव्यादीनां कर्मणोनभिधानात्कृत्यानां कर्तृग्रहणम्॥ * ॥

(भाष्यम्) भव्यादीनां कर्म कृत्यैरनभिहितं 'गेयो माणवकः साम्नाम्' भव्यादीनां कर्मणोनभिधानात्कृत्यानां कर्तृग्रहणं क्रियते॥

(उद्द्योतः) भव्यादीनामिति। तत्र हि कर्तरि कृत्यः। गेयो माणवकः साम्नामित्यत्र कर्मणि विकल्पाभावायेत्यर्थः॥

(आक्षेपभाष्यम्)

किमुच्यते—भव्यादीनां कर्म कृत्यैरनभिहितमिति, नेहाप्यनभिहितं भवति—आक्रष्टव्या ग्रामं शाखेति॥

(प्रदीपः) कृत्यानाम्॥ ७१॥ नेहापीति। काकानप्रयोगादिहाप्यनभिधानमित्यर्थः॥ आक्रष्टव्येति। कृषेर्द्विकर्मकत्वात् प्रधानकर्मणः कृत्येनाभिधानं न त्वप्रधानकर्मण इति तन्निवृत्त्यर्थमपि कर्तृग्रहणं कस्मान्न भवतीति भावः॥

(उद्द्योतः) तन्निवृत्त्यर्थमपीति। कृत्यानां प्रयोगे कर्तर्येव षष्ठी न कर्मणि सा च वेति कस्मान्न व्याख्यायत इत्यर्थः। यद्यप्येवं व्याख्याने गेयो माणवकः साम्नामिति न सिध्यति, तथापि उभयप्राप्तावित्यनुवर्त्य तत्र दोषाभाव इति भावः॥

(समाधानभाष्यम्)

एवं तर्हि योगविभागः करिष्यते—"कृत्यानाम्" कृत्यानां प्रयोगे षष्ठी न भवतीति। किमुदाहरणम्?। ग्राममाक्रष्टव्या शाखा॥ ततः "कर्तरि वा" इति॥

(प्रदीपः) एवं तर्हीति। कृत्यानामित्येतावत् सूत्रं क्रियते। तत्र चोभयप्राप्ताविति नेति च वर्तते। तेन कर्तृकर्मणोर्द्वयोरप्युभयप्राप्तौ कृत्ये षष्ठी प्रतिषिध्यते॥

(उद्द्योतः) अत्र पक्षे विधिसम्भवे नियमानुपपत्तिरनुभयप्राप्तिविषये भवतः कटः कर्तव्यो भवता कटः कर्तव्य इत्यादावसिद्धिं च मनसि निधाय भाष्ये उक्तम् एवं तर्हीति॥ कर्तृकर्मणोर्द्वयोरपीति। विकल्पस्त्वनुभयप्राप्तिविषयः आक्रष्टव्या ग्रामं शाखा देवदत्तेनेत्यस्यैवेष्टेरित्याशयः॥ वृत्तिस्वरसोप्येवमेव। भाष्ये ग्राममाक्रष्टव्येत्यस्य देवदत्तेनेति शेषः॥ उभयप्राप्तावित्यस्य सम्बन्धाऽज्ञानेन वा तत्रेदमुदाहृतम्॥ देवदत्तस्य देवदत्तेन वा कर्तव्यमिति कर्तरि वेत्यस्योदाहरणम्॥

(आक्षेपभाष्यम्)

इहापि तर्हि प्राप्नोति—गेयो माणवकः साम्नामिति॥

(उद्द्योतः) इहापि तर्हि प्राप्नोतीति। निषेध इति शेषः॥

(समाधानभाष्यम्)

उभयप्राप्ताविति वर्तते॥

(समाधानबाधकभाष्यम्)

ननु चोभयप्राप्तिरेवैषा। गेयो माणवकः साम्नामिति च गेयानि माणवकेन सामानीति च भवति॥

(प्रदीपः) उभयप्राप्तिरेवैषेति। पर्यायेणेति मन्यते॥

(उद्योतः) ननु चोभयप्राप्तिरिति ॥ उभयप्राप्ताविति तत्पुरुष इति भावः । बहुव्रीहिरित्युत्तरम् ॥ पर्यायेणेति । कर्तरि भव्यादीनां विकल्पेन विधानादित्यर्थः ॥

(समाधानसाधकभाष्यम्)

उभयप्राप्तिर्नाम सा भवति, यत्रोभयस्य युगपत्प्रसङ्गः । अत्र च यदा कर्मणि न तदा कर्तरि । यदा कर्तरि न तदा कर्मणीति ॥ कृत्यानाम् ॥ ७१ ॥

इति श्रीभगवत्पतञ्जलिविरचिते व्याकरणमहाभाष्ये द्वितीयस्याध्यायस्य तृतीये पादे तृतीयमाह्निकम् ॥ पादश्च समाप्तः ॥

(प्रदीपः) उभयप्राप्तिर्नामेति । बहुव्रीहिसमासाश्रयणादत्र कृत्ये युगपदुभयोः प्राप्तिस्तत्रैव षष्ठी निषिध्यत इत्यर्थः ॥ ७१ ॥

इत्युपाध्यायजैयटपुत्रकैयटकृते भाष्यप्रदीपे द्वितीयाध्यायस्य तृतीये पादे तृतीयमाह्निकम् । समाप्तश्चायं तृतीयः पादः ॥

(उद्योतः) बहुव्रीहीति । कदाचित्कर्मणि कृत्यसत्त्वेन कृत्यप्रत्ययभेदादेकत्र कृत्ये युगपदुभयप्राप्तिर्नास्तीति भावः ॥ अनेन भाष्येण यत्रोभयोः प्रयोगस्तत्रैवोभयप्राप्तिरिति सूचितम् ॥ ७१ ॥

इति शिवभट्टसुतसतीगर्भजनागेशभट्टकृते भाष्यप्रदीपोद्योते द्वितीयस्याध्यायस्य तृतीये पादे तृतीयमाह्निकं, पादश्च समाप्तः ॥

द्वितीयाध्यायस्य चतुर्थपादे प्रथममाह्निकम् ॥

(एकवद्भावप्रकरणम्)

(३३६ अतिदेशसूत्रम् ॥ २ । ४ । १ आ. १ सू.)

५३२ द्विगुरेकवचनम् ॥ २।४।१ ॥

(सूत्रप्रयोजनाधिकरणम्)

(आक्षेपभाष्यम्)

किमर्थमिदमुच्यते ? ॥

(१५५४ समाधानवार्तिकम् ॥ १ ॥)

॥ * ॥ प्रत्यधिकरणं वचनोत्पत्तेः संख्यासामानाधिकरण्याच्च द्विगोरेकवचनविधानम् ॥ * ॥

(भाष्यम्) प्रत्यधिकरणं वचनोत्पत्तिर्भवति ॥ किमिदं प्रत्यधिकरणमिति ? । अधिकरणमधिकरणं प्रति प्रत्यधिकरणम् ॥ संख्यासामानाधिकरण्याच्च । संख्यया बह्वर्थया चास्य सामानाधिकरण्यम् । प्रत्यधिकरणं वचनोत्पत्तेः संख्यासामानाधिकरण्याच्च "बहुषु बहुवचनम्" इति बहुवचनं प्राप्नोति । इष्यते चैकवचनं स्यादिति । तच्चान्तरेण यत्नं न सिध्यतीति द्विगोरेकवचनविधानम् । एवमर्थमिदमुच्यते ॥

(प्रदीपः) द्विगुरेकवचनम् ॥ १ ॥ किमर्थमिति । इह समाहारद्विगोरेव ग्रहणमिष्यते । समाहरणं समाहारः । स चैक एवेति सिद्धमेकवचनमिति प्रश्नः ॥ प्रत्यधिकरणमिति । समाह्रियत इति समाहार इति यदा कर्मणि घञ् तदानेकस्यार्थस्य समाह्रियमाणस्य वाचको द्विगुरिति एकत्वाभावादप्राप्तमेकवचनं विधीयत इत्यर्थः । अधिकरणशब्देन द्रव्यमुच्यते । यत्संख्यद्रव्याभिधानं तत्संख्याश्रयं वचनमुत्पद्यत इत्यर्थः । पञ्चपूलीशब्देनात्र पञ्च पूलाः समाह्रियमाणा उच्यन्ते । ततो बहुवचनप्रसङ्गे एकवचनविधानम् ॥ संख्यासामानाधिकरण्याच्चेति । एतेन कर्मसाधनत्वं समाहारशब्दस्य दर्शयति । भावसाधने हि वैयधिकरण्यं पञ्चानां पूलानां समाहार इति । संख्याशब्देन संख्यावाची शब्द उच्यते ॥ संख्यया बह्वर्थयेति । एकत्वनिरासपरमेतत् । तेन यद्यपि गृह्यते संख्या द्वित्वमामीति ॥

(उद्द्योतः) द्विगुरे ॥ १ ॥ तद्धितार्थेत्यत्र विहितस्य सर्वस्य द्विगुत्वात्समाहारद्विगोरेव ग्रहणे मानाभावः तन्मात्रग्रहणेऽपि समाहारशब्दस्य कर्मसाधनत्वे बहुवचनप्राप्तेर्वक्ष्यमाणमद्रीत्या भावसाधनत्वेऽपि तत्प्राप्तेः प्रश्नानुपपत्तिरत आह—इहेति । कर्मसाधनस्य ग्रहणं तु तत्रैव भाष्ये निराकृतम् ॥ द्रव्यमिति । गुणादीनामाधारत्वादित्यर्थः ॥ एकद्रव्यवाचकत्वरूपसामानाधिकरण्यस्य शब्दधर्मत्वादाह—संख्याशब्देनेति ॥ उच्यते इति । अत एव द्विगुपदेन सामानाधिकरण्यं पारिभाषिकग्रहणे हि द्विगोरिति पञ्चमी स्यादिति भावः ॥ वचनमिति च सामान्ये नपुंसकं बोध्यम् ॥

(काकुभाष्यम्)

अस्ति प्रयोजनमेतत् । किं तर्हीति ॥

(अनुप्रयोगेप्येकवचनसाधनाधिकरणम्)

(१५५५ आक्षेपवार्तिकम् ॥ २ ॥)

॥ * ॥ तत्रानुप्रयोगस्यैकवचनाभावोऽद्विगुत्वात् ॥ * ॥

(भाष्यम्) तत्रानुप्रयोगस्यैकवचनं न प्राप्नोति 'पञ्चपूलीयम्' इति ॥ किं कारणम् ?। अद्विगुत्वात् । "द्विगुरेकवचनम्" इत्युच्यते । न चात्रानुप्रयोगो द्विगुसंज्ञः ॥

(प्रदीपः) तत्रानुप्रयोगस्येति । द्विगुः समास एकवचनं प्रत्ययं प्रतिपद्यते इति पारिभाषिकैकवचनाश्रयेण दोषोपन्यासः ॥

(१५५६ समाधानाय न्यासान्तरवार्तिकम् ॥ ३ ॥)

॥ * ॥ सिद्धं तु द्विग्वर्थस्यैकवद्वचनात् ॥ * ॥

(भाष्यम्) सिद्धमेतत् ॥ कथम् ? । द्विग्वर्थ एकवद्भवतीति वक्तव्यम् ॥

(आक्षेपभाष्यम्)

तत्तर्हि वक्तव्यम् ? ॥

(समाधानभाष्यम्)

न वक्तव्यम् । नेदं पारिभाषिकस्य वचनस्य ग्रहणम् । किं तर्हि ? । अन्वर्थग्रहणम्—उच्यते वचनम्, एकस्यार्थस्य वचनमेकवचनमिति ॥

(प्रदीपः) उच्यते वचनमिति । कृत्यल्युटो बहुलमिति कर्मणि ल्युट् ॥ एकस्यार्थस्येति । वाच्यवाचकसंबन्धे षष्ठी । एकस्यार्थस्य वाचको द्विगुः समास उच्चार्यत इत्यर्थः ॥ तत्र सामर्थ्यादयमतिदेश उपपद्यते । यो ह्यनेकस्यार्थस्य वाचकः स कथमेकस्य वाचकस्तस्मादेकत्वाश्रयकार्यप्राप्तये द्विग्वर्थस्यैकवद्भावो विधीयते । ततश्च तस्मिन्नर्थे प्रयुज्यमानस्याद्विगोरप्येकवचनं सिध्यति ॥

(उद्द्योतः) द्विग्वर्थस्येति । एवं चानुप्रयोगेऽपि सिद्धिरिति भावः ॥

(एकशेषेबहुवचनसाधनाधिकरणम्)

(१५५७ आक्षेपवार्तिकम् ॥ ४ ॥)

॥ * ॥ एकशेषप्रतिषेधश्च ॥ * ॥

(भाष्यम्) एकशेषे च प्रतिषेधो वक्तव्यः । पञ्चपूली च पञ्चपूली च पञ्चपूली च पञ्चपूल्यः ॥

(प्रदीपः) एकशेषप्रतिषेधश्चेति । एकशेषविषय एकवद्भाव उपचारादेकशेषशब्देनोक्तः ॥ पञ्चपूल्य इति । अत्रैकशेषे कृतेपि द्विगुत्वात्तदर्थस्यैकवद्भावः प्राप्तः प्रतिषिध्यते ॥

(उद्योतः) षष्ठीसमासेऽर्थानुपपत्तिमाशङ्क्याह—एकशेषविषय इति ॥ एकशेषे चेति तु भाष्ये विषयसप्तमी ॥ भाष्यस्वारस्यात्तु विषयसप्तम्यन्तेन सुप्सुपेति समास इति लभ्यते ॥

(१५५८ समाधानवार्तिकम् ॥ ५ ॥)

॥ * ॥ न वान्यस्यानेकत्वात् ॥ * ॥

(भाष्यम्) न वा वक्तव्यः ॥ किं कारणम् ? । अन्यस्यानेकत्वात् । नैतद्द्विगोरनेकत्वम् ॥ कस्य तर्हि ? । द्विग्वर्थसमुदायस्य ॥

(प्रदीपः) नवेति । प्रथमस्य द्विग्वर्थस्यानेकसंख्यायुक्तस्यानेनैकवद्भावः कृतः । तत एकशेषे कृते द्विग्वर्थसमुदायस्याद्विग्वर्थत्वाद् बहिरङ्गत्वाच्च प्राथमकल्पिकेऽन्तरङ्गे द्विग्वर्थे चरितार्थत्वाच्चैकवद्भावो न प्रवर्तत इत्यर्थः ॥

(उद्योतः) भाष्ये—नैतन् द्विगोरिति ॥ द्विग्वर्थस्येत्यर्थः ॥ समुदायस्येति । उद्भूतावयवभेदस्येत्यर्थः ॥ यद्यपि शिष्यमाणं लुप्यमानार्थाभिधायीति अयमपि द्विग्वर्थ एव तथापि न दोष इत्याह—बहिरङ्गत्वाच्चेति ॥ बहुवचनसमभिव्याहारेणैवास्य प्रतीत्या ज्ञातसंस्कारानिवृत्तिरित्याशयमन्ये ॥

(तद्धितार्थद्विगौ एकवद्भावपरिहाराधिकरणम्)

(१५५९ आक्षेपवार्तिकम् ॥ ६ ॥)

॥ * ॥ समाहारग्रहणं च तद्धितार्थप्रतिषेधार्थम् ॥ * ॥

(भाष्यम्) समाहारग्रहणं च कर्तव्यम् । किं प्रयोजनम् ? । तद्धितार्थप्रतिषेधार्थम् । तद्धितार्थे यो द्विगुस्तस्य मा भूत्—पञ्चकपालौ पञ्चकपाला इति ॥

(प्रदीपः) पञ्चकपालाविति । संस्कृतार्थे विहितस्याणो द्विगोर्लुगनपत्य इति लुक् ॥

(समाधानाय प्रत्याक्षेपभाष्यम्)

किं पुनरयं पञ्चकपालशब्दः प्रत्येकं परिसमाप्यते, आहोस्वित्समुदाये वर्तते ? ॥

(प्रदीपः) किं पुनरिति । यदि तावदेकस्मिन् संस्कृते प्रत्ययमुत्पाद्य लुकि कृते एकशेषः क्रियते तदा पञ्चपूल्य इत्यनेन पञ्चकपाला इति समानम् ॥

(उद्योतः) पञ्चकपालशब्दस्य प्रत्येकं समुदाये वा परिसमाप्तौ तद्धितार्थे द्विगुत्वानपायात्किं विचारेणेत्यत आह—यदि तावदिति ॥ समानमिति । अयमेव पुरस्तादेव चोदितं परिहृतं चेति भाष्यस्यार्थः ॥

(संदेहबीजभाष्यम्)

किं चातः ? ॥

(प्रथमपक्षाङ्गीकारेविशेषप्रदर्शनभाष्यम्)

यदितावत्प्रत्येकं परिसमाप्यते, पुरस्तादेव चोदितं परिहृतं च ॥

(द्वितीयपक्षाङ्गीकारभाष्यम्)

अथ समुदाये वर्तते ॥

(१५६० द्वितीयपक्षे विशेषप्रदर्शनवार्तिकम् ॥ ७ ॥)

॥ * ॥ न वा समाहारैकत्वात् ॥ * ॥

(भाष्यम्) न वैतत् समाहारैकत्वादपि सिध्यति ॥

(प्रदीपः) अथ प्रथममेव पञ्चसु कपालेषु संस्कृता इति बहुत्वसंख्यायुक्ता अर्था विवक्ष्यन्ते तदा तेषां समाह्रियमाणत्वात् समाहाररूपतास्तीति क्रियमाणेपि समाहारग्रहणे निवृत्तिर्न सिध्यतीत्यर्थः ॥

(उद्योतः) समाह्रियमाणत्वादिति । समुदायरूपत्वादित्यर्थः ॥ समुदायसमाहारौ च पर्यायाविति भावः ॥ निवृत्तिर्न सिध्यतीति । समाहारानुवादेनैकत्वविधानादप्येतन्न सिध्यतीति भाष्याक्षरार्थः ॥

(प्रथमपक्षाङ्गीकारभाष्यम्)

एवं तर्हि प्रत्येकं परिसमाप्यते ॥ पुरस्तादेव चोदितं परिहृतं च ॥

(प्रदीपः) एवन्तर्हीति । नहि द्वयोर्बहूनां वा पुरोडाशानां पञ्चसु कपालेषु संस्कारः क्रियते । अपि तु प्रत्येकमिति भावः ॥

(उद्योतः) प्रत्येकमेव समाप्तिरित्यत्र विनिगमकमाह—नहीति । एवं च न वा समाहारैकत्वादिति निष्फलम् । किं च समासे संख्याविशेषानवगतेः समुदायमादाय बहुवचनोपपत्तिरपि नेति भाष्याशयः ॥

(व्याख्यान्तरभाष्यम्)

अपर आह—

न वा समाहारैकत्वात् ॥

न वा योगारम्भेणैवार्थः । किं कारणम् ? । समाहारैकत्वादेकवचनं भविष्यति ॥ द्विगुरेक ॥ १ ॥

(प्रदीपः) **अपर आहेति । न वा समाहारैकत्वादि**त्येतद्वार्तिकं सूत्रप्रत्याख्यानार्थमित्येतद्व्याचष्टे ॥ अयं भावः—तिरोहितावयवभेदः समूहरूपः समाहारो द्विग्वर्थस्तस्यैकत्वाद्वनयूथादिवत्सिद्धमेकवचनमिति नार्थः सूत्रेण । तस्मिंश्चासति समाहारग्रहणं न कर्तव्यम् । क्रियमाणे तु सूत्रे समाहारग्रहणं तद्धितार्थद्विगुव्यावृत्त्यर्थं कर्तव्यमेव । तेन समाहारेण व्यपदिष्टस्य द्विगोर्ग्रहणं भवति । यस्तु तद्धितार्थे न तस्य भवति । तेन पञ्चभिर्गोभिः क्रीताः पञ्चगवः पटा इत्यादौ द्विग्वर्थस्यैकवद्भावाभावः । यदा बहूनां पटानां पञ्चगुत्वं न तु प्रत्येकं तदैकशेषस्यायमविषयः । एतदेव मन्यमानेन भाष्यकारेण पूर्वव्याख्यानेऽसमाश्वसता प्रत्याख्यानत्वेन वार्तिकं व्याख्यातम् । उत्तरपदे तु यो द्विगुस्तदर्थस्यार्थान्तरे गुणभावादस्वातन्त्र्यात्सत्यपि प्रातिपदिकत्वे ततः प्रत्ययानुत्पादादेकवद्भावातिदेशः प्रयोजनाभावान्न प्रवर्तते ॥ १ ॥

(उद्द्योतः) **तिरोहितेति** । लक्ष्यानुरोधादिति भावः । अत्र पक्षे द्रव्यानयनं तु नान्तरीयकत्वात् द्रव्याकृत्योरभेदन्यायेन वा ॥ अवश्यं च भावसाधन एव समाहारशब्दस्तत्राश्रयणीयः । अन्यथा पञ्चखट्वीत्यादावनुपसर्जनत्वाद् ह्रस्वो न स्यात् । एवं च न्यायसिद्धार्थानुवादकमेवेदं सूत्रमिति बोध्यम् ॥ समुदाये शब्दसमाप्तौ पञ्चगवः पटा इत्यादौ तद्धितार्थेऽपि समाहारसम्भवात्कथं तेनापि तद्व्यावृत्तिरत आह—**समाहारेण व्यपदिष्टस्येति** ॥ प्रतिपदोक्तपरिभाषया तद्धितार्थद्विगोश्च तत्त्वाभावादिति भावः ॥ पञ्चपूल्य इत्यनेन नेदं तुल्यमित्याह—**यदा बहूनामिति ॥ असमाश्वसतेति** । वस्तुतः समासेन्तर्वर्तिविभक्त्यर्थसंख्यानवगमेन सर्वत्र समासादेकशेषेणैव बहुवचनादीति भाष्याशयः ॥ अतएवैवं **तर्हीत्यादि परिहृतं चे**त्यन्तं भाष्यं संगच्छते ॥ अन्यथा तदसंगतिरित्यन्ये ॥ उत्तरपदद्विगुस्तु न समाहारग्रहणस्य व्यावर्त्य इत्याह—**उत्तरपदत्वे त्विति ॥ सत्यपि प्रातिपदिकत्वे इति** । तत्त्वे सत्यपि स्वगतसंख्याद्यभावान्न ततः प्रत्यय इति ५।५।५ पञ्चगवप्रिय इत्यादौ प्रत्ययान्तत्वाभावाच्च न प्रातिपदिकत्वमित्यपिना सूचितम् ॥ १ ॥

(३२७ एकवद्भावसूत्रम् ॥ २। ४। १ आ० २)

५३३ द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम् ॥ २।४।२ ॥

(अनिष्टापत्तिवारणाधिकरणम्)

(१५६१ शेषपूर्तिवार्तिकम् ॥ १ ॥)

॥ * ॥ प्राणितूर्यसेनाङ्गानां तत्पूर्वपदोत्तरपदग्रहणम् ॥ * ॥

(भाष्यम्) **प्राणितूर्यसेनाङ्गानां तत्पूर्वपदोत्तरपदग्रहणं कर्तव्यम् । प्राण्यङ्गानां प्राण्यङ्गैरिति वक्तव्यम् । तूर्याङ्गानां तूर्याङ्गैरिति वक्तव्यम् । सेनाङ्गानां सेनाङ्गैरिति वक्तव्यम् ॥ किं प्रयोजनम् ? । व्यतिकरो मा भूदिति ॥**

(प्रदीपः) **द्वन्द्वश्च ॥ २ ॥ तत्पूर्वपदोत्तरपदग्रहणमिति** । यदङ्गवाचि पूर्वपदं तदङ्गवाच्येव यद्युत्तरपदं भवति तथा सत्येकवद्भावो नान्यथेत्यर्थः ॥ **व्यतिकरो मा भूदिति** । पाणिमार्दङ्गिकाश्वारोहा इत्यादावेकवद्भावो मा भूदित्यर्थः ॥

(आक्षेपभाष्यम्)

तर्हि वक्तव्यम् ? ॥

(समाधानभाष्यम्)

न वक्तव्यम् ॥

(१५६२ समाधानहेतुवार्तिकम् ॥ २ ॥)

॥ * ॥ योगविभागात्सिद्धम् ॥ * ॥

(भाष्यम्) **योगविभागः करिष्यते—"प्राण्यङ्गानाम्" । ततः—"तूर्याङ्गानाम्" । ततः "सेनाङ्गानाम्" इति ॥**

(आक्षेपभाष्यम्)

स तर्हि योगविभागः कर्तव्यः ? ॥

(समाधानभाष्यम्)

न कर्तव्यः । प्रत्येकमङ्गशब्दः परिसमाप्यते ॥ द्वन्द्वश्च ॥ २ ॥

(प्रदीपः) **प्रत्येकमिति** । बहुवचनान्तोऽङ्गशब्दः प्रत्येकमभिसंबध्यत इति भावः ॥ पूर्वपक्षेऽपि प्रत्येकमेवाङ्गशब्दस्य संबन्धः । स त्वन्यथा—प्राण्यङ्गतूर्याङ्गसेनाङ्गवाचिनां द्वन्द्व एकवदिति । नहि प्राणितूर्यसेनानामेकमङ्गं संभवतीति सामर्थ्यादेव प्रत्येकपरिसमाप्तिरङ्गशब्दस्य सिद्धा ॥ तस्मादन्यथा प्रत्येकं परिसमाप्तिर्बहुवचनान्तस्य सतः प्रतिपाद्यते । तेनास्माद् ग्रहणकवाक्याल्लक्ष्यसंस्कारकं वाक्यत्रयमुपप्लवत इति संकरो न भवति ॥ २ ॥

(उद्द्योतः) **द्वन्द्वश्च** ॥ २ ॥ पूर्वपक्षेऽपि प्रत्येकमङ्गशब्दसम्बन्धे युक्तिमाह—**नहीति** ॥ एवं च पूर्वपक्षात्सिद्धान्ते को विशेष इत्यत आह—**तस्मादन्यथेति** । 'अङ्गानाम्' इत्येवंरूपबहुवचनान्तस्य सतः प्रत्येकं समाप्तिरित्यर्थः ॥ पूर्वपक्षे प्राण्यङ्गस्य तूर्याङ्गसेनाङ्गेत्यादिवचनव्यवस्था व्यतिकरः शङ्कितः । सिद्धान्ते तु **प्राण्यङ्गाना**मित्यादिबहुवचनान्तलक्ष्यसंस्कारकवाक्यत्रयलाभात् प्राण्यङ्गानां प्राण्यङ्गैरेव समास एकवद्भाव इति विशेष इति भावः ॥ केवलप्रातिपदिकस्य पदान्तरेणान्वयायोगाद्विभक्त्यन्तस्यैवान्वयो वाच्यः । तथा च श्रूयमाणविभक्तिं त्यक्त्वा विभक्त्यन्तरकल्पने गौरवाद्बहुवचनान्तस्यैवाङ्गशब्दस्यान्वय इति तात्पर्यम् ॥ **वाक्यत्रयमिति** । बहुवचना-

न्ताङ्गशब्दघटितमित्यर्थः॥ अत्र तूर्याङ्गशब्दे न वादका एव गृह्यन्ते, मृदङ्गशङ्खतूणवा इत्यत्पाच्तरमिति सूत्रे भाष्यप्रयोगात्। तत्साहचर्याच्च सेनाङ्गशब्देन रथाद्यारूढानामेव ग्रहणम् । संग्रामं हस्त्यश्वरथपदातिभिरिति येन विधिरिति सूत्रस्थभाष्यस्वरसाच्च ॥ फलसेनेत्यत्र तु सेनाशब्देन हस्तिरथादय एवेत्याहुः ॥ २ ॥

(३३८ एकवद्भावसूत्रम् ॥ २।४।१ आ. ३ ॥)

५३४ अनुवादे चरणानाम् ॥ २।४।३ ॥

(प्रदीपः) अनुवादे ॥ ३ ॥ यदा प्रतिपत्ता प्रमाणान्तरावगतमप्यर्थं कार्यान्तरार्थं प्रयोक्ता प्रतिपाद्यते तदानुवादो भवति ॥ ३ ॥

(उद्योतः) अनुवादे ॥ ३ ॥ प्रतिपत्ता श्रोता ॥

(आक्षेपभाष्यम्)

इह कस्मान्न भवति—नन्दन्तु कठकालापाः, वर्धन्तां कठकौथुमाः ? ॥

(१५६३ समाधानवार्तिकम् ॥ १ ॥)

॥ * ॥ स्थेणोः ॥ * ॥

(व्याख्याभाष्यम्)

स्थेणोरिति वक्तव्यम् ॥

(आक्षेपभाष्यम्)

एवमपि तिष्ठन्तु कठकालापा इत्यत्रापि प्राप्नोति ॥

(१५६४ समाधानवार्तिकम् ॥ २ ॥)

[॥ * ॥ अद्यतन्यां च ॥ * ॥]

(भाष्यम्) अद्यतन्यां चेति वक्तव्यम् । उदगात्कठकालापम् । प्रत्यष्ठात्कठकौथुमम् । उदगात्कौमोदपैप्पलादम् ॥ अनुवादे ॥ ३ ॥

(उद्योतः) अद्यतन्यामित्यद्यतनीति लुङः संज्ञा ॥ ३ ॥

(३३९ एकवद्भावसूत्रम् ॥ २।४।१ आ० ४)

५३८ विशिष्टलिङ्गो नदीदेशोऽग्रामाः ॥ २।४।७ ॥

(अनिष्टवारणाधिकरणम्)

(१५६५ प्रतिप्रसववार्तिकम् ॥ १ ॥)

॥ * ॥ ग्रामप्रतिषेधे नगरप्रतिषेधः ॥ * ॥

(भाष्यम्) अग्रामा इत्यत्रानगराणामिति वक्तव्यम् । इह मा भूत्—मथुरापाटलिपुत्रमिति ॥

(प्रदीपः) विशिष्ट ॥ ७ ॥ जनपदविशेषो ग्रामः । ग्रामे नाध्येयम्, अभक्ष्यो ग्रामकुक्कुट इत्यादौ ग्रामग्रहणे नगरस्यापि ग्रहणदर्शनाद्वचनम्—अग्रामा इत्यत्रेति ॥

(उद्योतः) विशिष्टलि ॥ ७ ॥ जनपदविशेष इति । जनवासस्थानविशेष इत्यर्थः । ग्रामप्रतिषेधइति ॥ ग्रामग्रहणेन नगराणां ग्रहणं नेत्यर्थः ॥

(१५६६ वार्तिकम् ॥ २ ॥)

[॥ * ॥ उभयतश्च ॥ * ॥]

(भाष्यम्) उभयतश्च ग्रामाणां प्रतिषेधो वक्तव्यः । शौर्यं च केतवता च शौर्यकेतवते । जाम्बवं च शाल्डकिनी च जाम्बवशाल्डकिन्यौ ॥ विशिष्ट ॥ ७ ॥

(प्रदीपः) उभयत इति । ग्रामनगरोभयावयवे द्वन्द्वे ग्रामसंबन्ध्येव प्रतिषेधो वक्तव्यः । शौर्यं नगरम् । केतवता ग्रामः । जाम्बवं नगरम् । शाल्डकिनी ग्रामः ॥ ७ ॥

(उद्योतः) भाष्ये—उभयतश्चेति । यो ग्रामाणां प्रतिषेधः उभयतः ग्रामसर्वावयवकस्य ग्रामान्यतरावयवकस्य वेत्यर्थः ॥ नगरसर्वावयवके चानगराणामिति प्रतिषेध इति भावः ॥ तदाह—ग्रामनगरेत्यादि ॥ ७ ॥

(३४० एकवद्भावसूत्रम् ॥२।४।१ आ. ५)

५३९ क्षुद्रजन्तवः ॥ २।४।८ ॥

(क्षुद्रजन्तुत्वनिर्णयाधिकरणम्)

(आक्षेपभाष्यम्)

क्षुद्रजन्तव इत्युच्यते । के क्षुद्रजन्तवः? ॥

(प्रदीपः) क्षुद्रजन्तवः ॥ ८ ॥ स्मृतीनां विरुद्धानां दर्शनात्प्रश्नः—के क्षुद्रजन्तव इति ॥

(समाधानभाष्यम्)

क्षोत्तव्या जन्तवः क्षुद्रजन्तवः ॥

(प्रदीपः) क्षोत्तव्या इति । अर्हार्थे कृत्यः । ये क्षुद्यमाना अपि न म्रियन्ते जलौकःप्रभृतयः । ये तु म्रियन्ते ते पापनिमित्तत्वादक्षोदनार्हाः ॥

(उद्योतः) क्षुद्रज ॥ ८ ॥ अर्हार्थे इति । अनेन क्षुद्रशब्दे रगपि अर्हार्थः तेन जन्तुशब्दस्य कर्मधारय इति ध्वनितम् ॥

(आक्षेपभाष्यम्)

यद्येवं यूकालिक्षं कीटपिपीलिकं दंशमशकमिति न सिध्यति ॥

(समाधानभाष्यम्)

एवं तर्ह्यनस्थिकाः क्षुद्रजन्तवः ॥

(लक्षणान्तरभाष्यम्)

अथ वा येषां स्वं शोणितं नास्ति ते क्षुद्रजन्तवः ॥

(उद्द्योतः) स्वशोणितं नास्तीति । यथा जलौकःप्रभृतीनाम् ॥ ८ ॥

(लक्षणान्तरभाष्यम्)

अथ वा येषामासहस्रादञ्जलिर्न पूर्यते ते क्षुद्रजन्तवः ॥

(लक्षणान्तरभाष्यम्)

अथ वा येषां गोचर्ममात्रं राशिं हत्वा न पतति ते क्षुद्रजन्तवः ॥

(सिद्धान्तलक्षणम्)

अथ वा नकुलपर्यन्ताः क्षुद्रजन्तवः ॥ क्षुद्रजन्त ॥ ८ ॥

(प्रदीपः) नकुलपर्यन्ता इति । एतदेव दर्शनमत्र व्यापित्वाद् गृह्यते । अत एवैतत्पश्चादुपन्यस्तम् ॥ ८ ॥

(३४१ एकवद्भावसूत्रम् ॥ २। ४। १ आ. ६)

५४० येषां च विरोधः शाश्वतिकः ॥ २।४।९ ॥

(आक्षेपभाष्यम्)

किमर्थश्चकारः ? ॥

(समाधानभाष्यम्)

एवकारार्थश्चकारः—येषां विरोधः शाश्वतिकस्तेषां द्वन्द्व एकवचनमेव यथा स्यात्, यदन्यत्प्राप्नोति तन्मा भूदिति ॥ किं चान्यत्प्राप्नोति? । ["विभाषा वृक्षमृग–" इति। तत्र] *पशुशकुनिद्वन्द्वे विरोधिनां पूर्वविप्रतिषिद्धम्* इत्युक्तम्, तन्न वक्तव्यं भवति ॥ येषां च ॥ ९ ॥

(प्रदीपः) येषां च ॥ ९ ॥ यदन्यदिति । चकारेण यत्नेन परो विकल्पो बाध्यते । तेनाश्वमहिषं काकोलूकमिति नित्य एकवद्भावो भवति ॥ ९ ॥

(उद्द्योतः) येषां च ॥ ९ ॥ यत्नेनेति । पुनर्विधानार्थेनेत्यर्थः ॥ ९ ॥

(३४२ एकवद्भावसूत्रम् ॥ २। ४। १ आ. ७)

५४१ शूद्राणामनिरवसितानाम् ॥ २।४।१० ॥

(अनिरवसितशब्दार्थाधिकरणम्)

(आक्षेपभाष्यम्)

'अनिरवसितानाम्' इत्युच्यते । कुतोऽनिरवसितानाम् ? ॥

(प्रदीपः) शूद्राणाम् ॥ १० ॥ निरवसिता बहिष्कृता उच्यन्ते । तत्रावधिप्रश्नः—कुत इति ॥

(समाधानभाष्यम्)

आर्यावर्तादनिरवसितानाम् ॥

(आक्षेपभाष्यम्)

कः पुनरार्यावर्तः ? ॥

(समाधानभाष्यम्)

प्रागादर्शात्प्रत्यक्कालकवनाद्दक्षिणेन हिमवन्तमुत्तरेण पारियात्रम् ॥

(प्रदीपः) प्रागादर्शादिति । आदर्शादयः पर्वतविशेषाः ॥ दक्षिणेनेति । एनबन्तः । एनपा द्वितीया । प्रागादिभ्यः प्रथमान्तेभ्यो देशवृत्तिभ्यः प्रत्ययो विहितः । एतत्पर्वतचतुष्टयमध्य आर्यावर्तो देश इत्यर्थः ॥

(उद्द्योतः) शूद्राणाम् ॥ १० ॥ प्रत्यय इति । दिक्शब्देभ्य इत्यादिनाऽस्तातिः, तस्य च लुगिति भावः ॥

(आक्षेपभाष्यम्)

यद्येवं किष्किन्धगन्धिकं शकयवनं शौर्यक्रौञ्चमिति न सिध्यति ॥

(प्रदीपः) यद्येवमिति । एतेषामार्यावर्ताद् बाह्यत्वादिति भावः ॥

(समाधानभाष्यम्)

एवं तर्ह्यार्यनिवासादनिरवसितानाम् ॥ कः पुनरार्यनिवासः ?॥ ग्रामो घोषो नगरं संवाह इति ॥

(प्रदीपः) ग्राम इति । एतेष्वार्या निवसन्तीति भावः । तत्र ग्रामः प्रसिद्धः । घोषो गोमहिष्यादिनिवासः । संवाहो वणिक्प्रधानः ॥

(आक्षेपभाष्यम्)

एवमपि य एते महान्तः संस्त्यायास्तेष्वभ्यन्तराश्चण्डाला मृतपाश्च वसन्ति तत्र चण्डालमृतपा इति न सिध्यति ॥

(प्रदीपः) संस्त्याया इति । निवासविशेषा इत्यर्थः । मृतपा डोम्बा इत्याहुः ॥

(उद्द्योतः) डोम्बा इति । श्मशाननिकटे ये वसन्ति मृतवस्त्रचितिकाष्ठादिसंग्राहकाश्चण्डालसदृशास्ते डोम्बा इत्युच्यन्ते ॥

(समाधानभाष्यम्)

एवं तर्हि याज्ञात्कर्मणोऽनिरवसितानाम् ॥

(प्रदीपः) याज्ञादिति । शूद्राणां पञ्चयज्ञानुष्ठानेऽधिकारोऽस्तीति भावः ॥

(उद्द्योतः) तस्माच्छूद्रो यज्ञेऽनवक्लृप्त इति श्रुतेः शूद्राणां यज्ञकर्मणोऽबहिष्कृतत्वं विरुद्धमित्यत आह—पञ्चेति । पूर्वोक्तश्रुतिस्त्वग्निहोत्रादिविषयेति भावः ॥

(आक्षेपभाष्यम्)

एवमपि तक्षायस्कारं रजकतन्तुवायमिति न सिध्यति ॥

(प्रदीपः) **तक्षायस्कारमिति** । तक्षादीनां यज्ञेऽधिकाराभावादिति भावः ॥

(उद्द्योतः) **तक्षादीनामिति** । तेषां प्रतिलोमत्वादिति भावः॥ शूद्रशब्दोऽत्र सूत्रे त्रैवर्णिकेतरपर इति बोध्यम् ॥

(सिद्धान्तसमाधानभाष्यम्)

एवं तर्हि पात्रादनिरवसितानाम् । यैर्भुक्ते पात्रं संस्कारेण शुध्यति तेऽनिरवसिताः । यैर्भुक्ते पात्रं संस्कारेणापि न शुध्यति ते निरवसिता इति ॥ शूद्राणाम् ॥ १० ॥

(प्रदीपः) **संस्कारेणेति** । यः संस्कारः स्मृतिकारैर्द्रव्यशुद्धौ पठितस्तेनैव न तदधिकेनेत्यर्थः ॥ १० ॥

(उद्द्योतः) **स्मृतिकारैरिति** । 'भस्मना शुध्यते कांस्यम्' इत्यादि ॥ १० ॥

(३४३ एकवद्भावसूत्रम् ॥ २ । ४ । १ आ. ८)

५४२ गवाश्वप्रभृतीनि च ॥ २।४।११॥

(गणपठितरूपविवक्षाधिकरणम्)

(१५६७ वार्तिकम् ॥ १ ॥)

॥ * ॥ गवाश्वप्रभृतिषु यथोच्चारितं द्वन्द्ववृत्तम् ॥ * ॥

(भाष्यम्) **गवाश्वप्रभृतिषु यथोच्चारितं द्वन्द्ववृत्तं द्रष्टव्यम् । गवाश्वम् । गवाविकम् । गवैडकम् ॥ गवाश्व ॥ ११ ॥**

(प्रदीपः) **गवाश्वप्र ॥ ११ ॥ यथोच्चारितमिति** । गणे यादृशाः कृतावङः पठिता द्वन्द्वास्तादृशानामेवेदं कार्यमेकवद्भावलक्षणं भवतीत्यर्थः । यदा त्ववङ् नास्ति तदा पशुद्वन्द्वे विभाषा भवति गोश्वं गोश्वा इति । एतेन गणपाठरूपं विवक्षितमित्युक्तं भवति ॥ ११ ॥

(उद्द्योतः) **गवाश्वप्र ॥ ११ ॥** भाष्ये—**यथोच्चारितं द्वन्द्ववृत्तमिति** । द्वन्द्वप्रयुक्तमिदं कार्यं गणे यथोच्चारितशब्दविषयमित्यर्थः । तत्फलितमाह—**गणे इति** । यथोच्चारितमित्यस्य फलमाह—**यदा त्विति** ॥ ११ ॥

(३४४ एकवद्भावसूत्रम् ॥ २ । ४ । १ आ. ९)

५४३ विभाषा वृक्षमृगतृणधान्यव्यञ्जनपशुशकुन्यश्ववडवपूर्वापराधरोत्तराणाम् ॥ २।४।१२ ॥

(नियमाधिकरणम्)

(१५६८ नियमवार्तिकम् ॥ १ ॥)

॥ * ॥ बहुप्रकृतिः फलसेनावनस्पतिमृगशकुनिक्षुद्रजन्तुधान्यतृणानाम् ॥ * ॥

(भाष्यम्) **फलसेनावनस्पतिमृगशकुनिक्षुद्रजन्तुधान्यतृणानां द्वन्द्वः विभाषा एकवद्भवति बहुप्रकृतिरिति वक्तव्यम् ॥ फल—बदरामलकम् । बदरामलकानि ॥ सेना—हस्त्यश्वम् । हस्त्यश्वाः ॥ वनस्पति—प्लक्षन्यग्रोधम् । प्लक्षन्यग्रोधाः ॥ मृग—रुरुपृषतम् । रुरुपृषताः ॥ शकुनि—हंसचक्रवाकम् । हंसचक्रवाकाः ॥ क्षुद्रजन्तु—यूकालिक्षम् । यूकालिक्षाः ॥ धान्य—व्रीहियवम् । व्रीहियवाः । माषतिलम् । माषतिलाः ॥ तृण—कुशकाशम् । कुशकाशाः । शरशीर्यम् । शरशीर्याः ॥ किं प्रयोजनम् ? । बहुप्रकृतिरेव यस्तत्र यथा स्यात् ॥ क मा भूत् ? । बदरामलके तिष्ठतः ॥**

(प्रदीपः) **विभाषा वृक्ष ॥ १२ ॥ बहुप्रकृतिरिति** । **बहवो** बहुत्वसंख्यायुक्ता वर्तिपदार्थाः **प्रकृतयः** कारणानि यस्य स बहुप्रकृतिः ॥ **बदरामलकमिति** । जातिरप्राणिनामित्येकवद्भावः । क्वचित्तु **बदरामलकानीत्यपि** पठ्यते । तत्रैवं व्याचक्षते—नित्य एकवद्भावे प्राप्ते विकल्पोऽनेन वचनेन क्रियते ॥ अन्ये तु बदरामलकानीत्येवं प्राप्ते जातिलक्षणो नित्य एकवद्भावो बहुप्रकृतेर्भवतीति प्रदर्श्यत इत्याहुः ॥ **हस्त्यश्वमिति** । सेनाङ्गत्वेऽपि परत्वात्पशुलक्षणो विकल्पो भवति ॥

(उद्द्योतः) **विभाषा वृक्ष ॥ १२ ॥** द्वन्द्वप्रकृतिर्वर्तिपदानि तेषां बहुत्वे त्रिप्रभृतिष्वेव स्यादत आह—**बहव इति** । पदार्थास्तादृशपदार्थप्रतिपादकाः शब्दाः तदर्थानां बहुत्वगमकश्चैकवद्भाव एव । यद्वा बदरत्वेनैवानेकेषां भानमेकवद्भावबलादिति नैकार्थाभावविरोधः एतत्सूत्रानुपात्तं फलं(ऽ)द्वन्द्वस्ये ह्योपादानं बहुप्रकृतिस्त्वनियमायेत्याह—**जातिरिति** । न च—जातिप्राधान्य एव **जातिरित्यस्य** प्राप्तिः । तत्र च न बहुवचनम्, तस्या एकत्वाद् । अत एव क्षीरो-

वृक्षे संयुपूर्के इत्यन्तादिवचेति सत्रसमाप्यप्रयोगः संगच्छते, आख्याख्यायामितिसूत्रं च भगवता प्रत्याख्यातम्—इति वाच्यम्। जातिप्राधान्ये एव जातौ व्यक्तिद्वारकपरम्परया संख्यान्वये तत्सम्भवात्॥ तदेवं जातिप्राधान्ये व्यक्तिद्वारकपरम्परया संख्यान्वये बदरामलकमित्येव ।पाठान्तरे आपव्याख्यायां **बदरामलकानीत्यपि** ॥ व्यक्तिप्राधान्ये तु बदरामलकानीत्यपि । जातौ साक्षात्संख्यान्वये बदरामलके इत्येव ।व्यक्तिप्राधान्ये व्यक्तेरेकत्वविवक्षायां बदरामलके बदरामलकमित्युभयमिति लभ्यते इति बोध्यम्॥ **व्याचक्षत इति** । अन्यत्र(ऽ)तस्येह पाठसामर्थ्याद्विकल्पो बहुप्रकृतित्वं चानेन विधीयत इति तदाशयः ॥ अत एव वार्तिकव्याख्यानभाष्ये विभाषेत्युक्तम्॥ **अन्येस्त्विति** । वार्तिकव्याख्यानभाष्ये विकल्पो न वाचनिकः किंतु **विभाषावृक्षेति** सूत्रप्राप्तिविषयानुवादकः ॥ तस्मादेषां य एकवद्भवति यश्च विभाषा एकवद्भवति स सर्वोऽपि बहुप्रकृतिरेवेति वाच्यमिति वार्तिकव्याख्यानभाष्यार्थः॥ एवमेव **यूकालिक्षा** इत्यपि भाष्यं व्याख्येयम्॥ अतएवाग्रे बहुप्रकृतिरेव यः तत्र यथा स्यादित्येव प्रयोजनमुक्तम्, न तु फलक्षुद्रजन्त्वंशे विकल्पोऽपि प्रयोजनत्वेनोक्त इति तदाशयः ॥ अत्राद्यव्याख्यैव युक्ता। भाष्यकारेण फलक्षुद्रजन्त्वोर्विभाषाप्रकरणे पाठः कर्त्तव्य इत्युच्यते । अतो न वार्तिकप्रयोजनकथनभाष्यविरोधः । यथोत्तरं मुनीनां प्रामाण्याच्चैवमेव युक्तमित्याहुः ॥ **सेनाङ्गत्वेऽपीति** । इदं चिन्त्यं तत्र सेनाङ्गशब्देन हस्त्यारोहादीनामेव ग्रहणात् । अत्र तु सेनाशब्देन हस्त्यश्वादीनां ग्रहणं भाष्यप्रामाण्यात् । अत एव **संग्रामं हस्त्यश्वरथपदातिभिरिति** भाष्यप्रयोगः सङ्गच्छते । बहुप्रकृतित्वाभावान्नैकवदिति तु न युक्तं, बहुभिरेव तैः संग्रामस्य निष्पाद्यत्वात् ॥ वनस्पतिशब्देन वार्तिके वृक्षग्रहणम् ॥

(आक्षेपभाष्यम्)

किं पुनरनेन या प्राप्तिः सा नियम्यते, आहोस्विद्—अविशेषेण? ॥

(प्रदीपः) **किं पुनरिति** । अस्मिन्प्रदेशे पठितत्वात्किमेतत्सूत्रविहित एव एकवद्भावो नियतविषयो व्यवस्थाप्यते अथ प्रकरणविहित इति प्रश्नः ॥ येषां सूत्रान्तरेणानेन च प्राप्तिर्वनस्पत्यादीनां तद्विषय एव संशयो न त्वन्यतरप्राप्तिविषयः ॥

(उद्द्योतः) एतत्सूत्रानुपात्तानामपि पाठात् प्रकरणविषयत्वनिश्चयेन संदेहानुपपत्तिरत आह—**येषामिति** । एतत्सूत्रोपात्तविषय एव सन्देह इति भावः॥

(भाष्यम्) किञ्चातः ? ॥

(प्रथमपक्षदूषणभाष्यम्)

यद्यनेन या प्राप्तिः सा नियम्यते, प्लक्षन्यग्रोधौ "जातिरप्राणिनाम्" इति नित्यो द्वन्द्वैकवद्भावः प्राप्नोति ॥

अथाविशेषेण, न दोषो भवति ॥

(उद्द्योतः) भाष्ये—**नित्यो द्वन्द्वैकवद्भावः प्राप्नोतीति** । अस्य नियमेन वारणेऽपि नित्यं प्राप्नोतीत्यर्थः ॥

अविशेषेणेति । यच्चैकवचनद्वन्द्वविषयं यदपच्छास्त्रं प्राप्नोति तद्बहुप्रकृतेरेवेत्यर्थ इति भावः ॥ एतेन बदरामलके इत्यत्र जातिरित्यस्याप्रवृत्तावपि चार्थे इति विभाषा स्यादित्यपास्तम् ॥

(द्वितीयपक्षाभ्युपगमभाष्यम्)

यथा न दोषस्तथास्तु ॥

(प्रदीपः) **यथा न दोष इति** । व्यापित्वात्प्रकरणापेक्षोयं विषयनियम इत्यर्थः ॥

(१५६९ पूर्वविप्रतिषेधवार्तिकम् ॥ २ ॥)

॥ * ॥ पशुशकुनिद्वन्द्वे विरोधिनां पूर्वविप्रतिषिद्धम् ॥ * ॥

(भाष्यम्) पशुशकुनिद्वन्द्वे विरोधिनां "येषां च विरोधः शाश्वतिकः" इत्येतद्भवति पूर्वविप्रतिषेधेन । पशुशकुनिद्वन्द्वस्यावकाशः—महाजोरभ्रम् । महाजोरभ्राः । हंसचक्रवाकम् । हंसचक्रवाकाः ॥ "येषां च विरोधः शाश्वतिकः" इत्यस्यावकाशः—श्रमणब्राह्मणम् ॥ इहोभयं प्राप्नोति—काकोलूकं श्वशृगालमिति । "येषां च विरोधः शाश्वतिकः" इत्येतद्भवति पूर्वविप्रतिषेधेन ॥

(आक्षेपभाष्यम्)

स तर्हि पूर्वविप्रतिषेधो वक्तव्यः? ॥

(समाधानभाष्यम्)

न वक्तव्यः । उक्तं चकारकरणस्य प्रयोजनम्—येषां च विरोधः शाश्वतिकस्तेषां द्वन्द्व एकवचनमेव यथा स्याद् यदन्यत्प्राप्नोति तन्मा भूदिति ॥

(१५७० पूर्वप्रतिषेधवार्तिकम् ॥ ३ ॥)

॥ * ॥ अश्ववडवयोः पूर्वलिङ्गत्वात्पशुद्वन्द्वनपुंसकम् ॥ * ॥

(भाष्यम्) अश्ववडवयोः पूर्वलिङ्गत्वात्पशुद्वन्द्वनपुंसकं भवति पूर्वविप्रतिषेधेन ॥ अश्ववडवयोः पूर्वलिङ्गत्वस्यावकाशः—विभाषा पशुद्वन्द्वनपुंसकम्, यदा न पशुद्वन्द्वनपुंसकं सोवकाशः—अश्ववडवौ ॥ पशुद्वन्द्वनपुंसकस्यावकाशः—अन्ये पशुद्वन्द्वाः—महाजोरभ्रं महाजोरभ्राः ॥ पशुद्वन्द्वनपुं-

सकप्रसङ्ग उभयं प्राप्नोति—'अश्ववडवम्' पशुद्व-न्द्वनपुंसकं भवति पूर्वविप्रतिषेधेन ॥

(प्रदीपः) अश्ववडवयोरिति । पशुत्वाद्विभाषैकवद्भावः । तत्रैकवद्भावपक्षे नपुंसकत्वमपि प्राप्नोति पूर्ववदश्ववडवावित्यतिदेशात् पुंस्त्वमपि । तत्र परत्वात् पुंस्त्वे प्राप्ते पूर्वविप्रतिषेध उच्यते ॥

(उद्द्योतः) पशुत्वेनैव सिद्धेऽश्ववडवग्रहणं न कार्यमित्याशयेन वार्त्तिकमित्याह—पशुत्वादिति ॥

(आक्षेपभाष्यम्)

स तर्हि पूर्वविप्रतिषेधो वक्तव्यः ? ॥

(समाधानभाष्यम्)

न वक्तव्यः ॥

(१५७१ समाधानहेतुवार्तिकम् ॥ ४ ॥)

॥ * ॥ प्रतिपदविधानात्सिद्धम् ॥ * ॥

(भाष्यम्) प्रतिपदमत्र नपुंसकं विधीयते—"अश्ववडवपूर्वापर—" इति ॥

(प्रदीपः) प्रतिपदविधानादिति । नात्र पशुग्रहणेनैकवद्भावो विधीयते किं तर्ह्यश्ववडवग्रहणेन तत्र प्रतिपदविधानात्स नपुंसकमित्येतद्भवति तच्छब्देन ह्येकवद्भावभाजं परामृश्य नपुंसकत्वं विधीयते । तेन यथैकवद्भावोत्र प्रतिपदं विधीयते तथा नपुंसकत्वमिति भावः ॥

(उद्द्योतः) नात्रेति । पूर्वविप्रतिषेधादश्ववडवग्रहणमेव न्याय्यमित्याशयः ॥ नपुंसकत्वस्य प्रतिपदविधित्वं समर्थयते—तच्छब्देनेति ॥

(१५७२ प्रत्याख्यानवार्तिकम् ॥ ५ ॥)

॥ * ॥ एकवचनमनर्थकं समाहारैकत्वात् ॥ * ॥

(भाष्यम्) एकवद्भावोऽनर्थकः॥ किं कारणम्? । समाहारैकत्वात् । एकोयमर्थः समाहारो नाम तस्यैकत्वादेकवचनं भविष्यति ॥

(प्रदीपः) समाहारैकत्वादिति । तिरोहितावयवभेदो हि समाहारः स च वनयूथादिवदेक इत्यर्थः ॥

(प्रत्याख्यानबाधकभाष्यम्)

इदं तर्हि प्रयोजनम्—एवं विज्ञास्यामि—इह नित्यो विधिः, इह विभाषेति ॥

(प्रदीपः) इह नित्य इति । द्वन्द्वश्चेत्यारभ्यास्माद्योगात्प्राग् नित्यो विधिः, अनेन तु योगद्वयेन विभाषेत्यर्थः ॥

(उद्द्योतः) भाष्ये—ज्ञास्यामीत्यन्तर्भावितण्यर्थः ज्ञापयिष्यामीत्यर्थः ॥ इह नित्य इति । विनिगमनाविरहात्प्राण्यङ्गादीनामेव समाहारस्तेषां समाहार एवेत्येवं द्विविधोऽपि नियम इति भावः । अन्यथा एतत्प्रयोजनखण्डनपरभाष्येणैषामेव समाहार इति नियमस्यैव लाभात् । एतद्विषय इतरेतरयोगाव्यावृत्त्या द्वन्द्वश्चेत्यारभ्यैतत्पर्यन्तं नित्यो विधिरित्यादि कैयटासङ्गतिः स्यात् ॥ भाष्यमपि विशिष्टप्रयोजनखण्डनपरम् ॥

(प्रत्याख्यानसाधकभाष्यम्)

नैतदस्ति प्रयोजनम् । आचार्यप्रवृत्तिर्ज्ञापयति—'सर्वो द्वन्द्वो विभाषैकवद्भवति' इति । यदयं "तिष्यपुनर्वस्वोर्नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनं नित्यम्" इत्याह ॥

(प्रदीपः) यदयमिति । यद्येतत्प्रकरणोपात्तानामेवैकवद्भावः स्यात्तदा तिष्यपुनर्वसुशब्दयोरत्रापठितत्वादेकवद्भावस्याभावात्तन्निवृत्तये बहुवचनग्रहणमनर्थकं स्यादित्यर्थः ॥

(उद्द्योतः) भाष्ये—यदयमिति । एवं चैकवद्भावप्रकरणं व्यर्थमिति भावः ॥ सर्वशब्दोऽसंकुचद्वृत्तिरित्यभिमानः ॥

(प्रत्याख्यानबाधकभाष्यम्)

इदं तर्हि प्रयोजनम्—"स नपुंसकम्" इति वक्ष्यामीति ॥

(प्रत्याख्यानसाधकभाष्यम्)

एतदपि नास्ति प्रयोजनम् । लिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्य ॥

(उद्द्योतः) लिङ्गमशिष्यमिति । शास्त्रोक्तलिङ्गानुशासनस्य व्यभिचारदर्शनादिति भावः ॥

(आक्षेपभाष्यम्)

न तर्हीदानीमिदं वक्तव्यम् ? ॥

(समाधानभाष्यम्)

वक्तव्यं च । किं प्रयोजनम्?। पूर्वत्र नित्यार्थम्, उत्तरत्र व्यभिचारार्थं "विभाषा वृक्षमृग" इति ॥

विभाषा वृ० ॥ १२ ॥

(प्रदीपः) पूर्वत्रेति । प्राण्यङ्गादीनां समाहार एवेत्येवमर्थमित्यर्थः ॥ उत्तरत्रेति । क्वचिज्जातिरप्राणिनामिति प्राप्ते विभाषा । मृगादीनां तु व्यतिकरनिरासार्थम् ॥ १२ ॥

(उद्द्योतः) एवं चान्यतरनियमस्य ज्ञापकान्निरासेऽन्यतर एव स्थित इत्याशयेनाह—प्राण्यङ्गादीनामिति । सर्वो द्वन्द्व इत्यत्र सर्वशब्द एतत्प्रकरणस्थसूत्रानुपात्तविषय इति भावः ॥ भाष्ये—उत्तरत्र व्यभिचारार्थमिति । नित्यैकवद्भावस्य व्यभिचारार्थमित्यर्थः । स च क्वचिदेकवद्भावाभावेन क्वचिन्नित्यत्वाभावेन ॥ एवं च मृगादीनां व्यतिकरे इतरेतरयोग एव, उत्तरसूत्रविषये अधिकरणवाचिनामितरेतरयोग एवेति ध्वनितम् ॥ तदुपपत्तिस्तु यो विभाषा एकवचनो द्वन्द्वः स मृगाणां मृगैरेव द्वन्द्वे ऽन्यत्र नेति वचनव्यक्त्या ॥ अन्यत्र विशेष्यभूतैकवचनं द्वन्द्वस्यैव । निषेधे इतरेतरयोग एवेति फलितत्वात् । एवं विप्रतिषिद्धं चेत्यत्रापि य एकवचनो विभाषा द्वन्द्वः स यदि विरुद्धार्थानां चेदद्रव्यवाचिनामेवेति वचनव्यक्त्या द्रव्यवाचिनामितरेतरयोग एव फलति ॥ १२ ॥

(३४५ एकवद्भावसूत्रम् ॥२।४।१ आ. १०)

५४७ विभाषा समीपे ॥ २।४।१६ ॥

(प्रत्याख्यानाधिकरणम्)

(आक्षेपभाष्यम्)

किमुदाहरणम् ? ॥

(प्रदीपः) **विभाषा स** ॥ १६ ॥ अनुप्रयोगे दोषदर्शनात्प्रश्नः—**किमुदाहरणमिति** ॥

(उद्द्योतः) विभाषा स ॥ १६ ॥ समाहारविषय उपदशं पाणिपादमित्येव, इतरेतरे तु उपदशाः पाणिपादाः इत्येवेष्यते विपरीतमपि प्राप्नोतीत्याशयेन प्रश्न इत्याह—**अनुप्रयोगे इति** ॥

(समाधानभाष्यम्)

उपदशं पाणिपादम्, उपदशाः पाणिपादाः ॥

(समाधानबाधकभाष्यम्)

नैतदस्ति प्रयोजनम् अयं द्वन्द्वैकवद्भाव आरभ्यते तत्र कः प्रसङ्गो यदनुप्रयोगस्य स्यात् ॥

(उद्द्योतः) भाष्ये—नैतदस्तीति । सूत्रेण द्वन्द्वस्यैकवद्भावविधानेपि अनुप्रयोगानियमस्तदवस्थ एवेति नेदं सूत्रप्रयोजनमित्यर्थः । प्रश्ने उदाहरणशब्दोऽपि प्रयोजनपर एवेति भावः ॥

(प्रत्याख्यानोपसंहारभाष्यम्)

एवं तर्ह्यव्ययस्य संख्ययाऽव्ययीभावोप्यारभ्यते बहुव्रीहिरपि । तद्यदा तावदेकवचनं तदाव्ययीभावोनुप्रयुज्यते एकार्थस्यैकार्थ इति । यदा बहुवचनं तदा बहुव्रीहिरनुप्रयुज्यते बह्वर्थस्य बह्वर्थ इति ॥ विभाषा ॥ १६ ॥

(प्रदीपः) **कः प्रसङ्ग इति** । नन्वर्थस्यैकवद्भावादनुप्रयोगस्यापि सेत्स्यति । नैतदस्ति । यदि तावदव्ययीभाव एवानुप्रयुज्यते तदा तस्याव्ययत्वादसंख्यत्वाद्बहुवचनं न स्यात् । सत्यपि वा तस्मिन्नमभावे कृते उपदशा इति न स्यात् । अथ बहुव्रीहिरेवानुप्रयुज्यते तदोपदशस्य पाणिपादस्येति षष्ठी स्यात् । उपदशमिति चेष्यते । एतदेव मनसिकृत्याह—**एवं तर्हीति** । अव्ययीभावोऽव्ययं विभक्तीति विहितः । बहुव्रीहिस्तु **संख्ययाव्ययेति** ॥ **तद्यदेति** । अव्ययीभावस्याव्ययत्वादसंख्यत्वादेकवचनस्य तूत्सर्गत्वादिति भावः ॥ **एकार्थ इति** । अभेदैकत्वाश्रयादित्याहुः ॥ **यदेति** । बहुव्रीहेः समीपिप्रधानत्वाद्बह्वर्थत्वमिति भावः ॥ १६ ॥

(उद्द्योतः) **नन्वर्थस्येति** । एवञ्च समाहारद्वन्द्वपक्षेऽव्ययीभावस्य बहुव्रीहेर्वाऽनुप्रयोगेऽपि द्वन्द्वार्थस्यैकवत्त्वादुपदशमित्येव भविष्यतीति भावः ॥ **अव्ययत्वादिति** । अव्ययत्वेनासंख्यत्वादित्यर्थः ॥ **सत्यपि वेति** । नाव्ययीभावात्तृतीयासप्तम्योरित्याद्यारम्भादसंख्यत्वमव्ययीभावातिरिक्ताव्ययविषयमिति भावः ॥ **अथेति** । अर्थस्यैकवत्त्वान्नित्यबहुवचनान्तस्याप्युपदशशब्दस्यैकवचनान्तत्वसम्पत्तावपि पाणिपादस्येति षष्ठ्यन्तसमभिव्याहारे उपदशेति अम्भावमनापन्नां षष्ठी श्रूयेतेति भावः ॥ वस्तुतो नियमे मानाभावेनोभयप्राप्त्युभयानुप्रयोगः स्यात् । तथा चेतरेतरयोगे उपदशं पाणिपादा इत्यपि स्यादिति भाष्यार्थः ॥ **एकवचनस्य त्विति** । तावतैव नाव्ययीभावादित्याद्युपपन्नं न संख्यासम्बन्धज्ञापकमिति भावः ॥ पञ्चमीतृतीयासप्तमीग्रहणं तु स्पष्टार्थमेव । पूर्वाचार्यानुरोधाद्वा । तदनुरोधफलं च तेषां प्रमादबोधनं क्वचित्, स्वकृतेः प्रामाण्यबोधनं क्वचित् इति बोध्यम् ॥ नन्वव्ययार्थे संख्याया अभावादेकार्थ इत्यनुपपन्नमत आह—**अभेदैकत्वेति** । तथाच भेदसहचरितद्वित्वाद्यभावरूपमैकार्थ्यं समीपप्रधानाव्ययीभावस्येत्यर्थः । एतेन समासे विशेष्यांशेऽपि अन्तर्वर्तिसंख्याया अभानं सूचितम् ॥ बहुवचनादि त्वेकशेषेणेति बोध्यम् ॥ १६ ॥

(इत्येकवद्भावप्रकरणम्)

(अथ लिङ्गानुशासनप्रकरणम्)

(३४६ नपुंसकत्वसूत्रम् ॥२।४।१ आ. ११)

५५० तत्पुरुषोऽनञ्कर्मधारयः॥२।४।१९॥

(सूत्रप्रयोजनाधिकरणम्)

(आक्षेपभाष्यम्)

किमर्थमिदमुच्यते ? ॥

(प्रदीपः) **तत्पुरुषो** ॥ १९ ॥ उत्तरेषु केषु चियोगेष्वन्यथासिद्धिं दृष्ट्वा पृच्छति—**किमर्थमिति** ॥

(एकदेशिसमाधानभाष्यम्)

"संज्ञायां कन्थोशीनरेषु" इति वक्ष्यति । तत्तत्पुरुषस्य नञ्समासस्य कर्मधारयस्य वा मा भूदिति ॥

(प्रदीपः) शिष्यबुद्धिपरीक्षार्थमन्यथासिद्धमपि तावत्प्रयोजनमाह । पश्चात्त्वनन्यथासिद्धं दर्शयिष्यति ॥

(समाधानबाधकभाष्यम्)

नैतदस्ति प्रयोजनम् । नहि संज्ञायां कन्थात उशीनरेष्वतत्पुरुषो नञ्समासः कर्मधारयो वास्ति॥

(प्रदीपः) **नहीति** । अनादिरत्र संज्ञा गृह्यते न त्विदानींतनीति भावः ॥

(उद्द्योतः) तत्पुरुषो नञ् ॥ १९ ॥ इदानीन्तनसंज्ञायामतत्पुरुषादेरपि सम्भवादाह—**अनादिरिति** ॥ **अत्रेति** । शास्त्रे शास्त्रस्यानादित्वादिति भावः ॥

(समाधानभाष्यम्)

उत्तरार्थं तर्हि—"उपज्ञोपक्रमं तदाद्याचिख्यासायाम्" इति वक्ष्यति, तदतत्पुरुषस्य नञ्समासस्य कर्मधारयस्य वा मा भूदिति ॥

(समाधानबाधकभाष्यम्)

नैतदस्ति प्रयोजनम् । नहि तदाद्याचिख्यासा-

थामुपक्षोपक्रमान्तोऽतत्पुरुषो नञ्समासः कर्मधारयो वास्ति ॥

(प्रदीपः) नहीति। षष्ठीतत्पुरुषाद्विना तदादित्वासंप्रत्ययः ॥

(समाधानभाष्यम्)

उत्तरार्थमेव तर्हि—"छाया बाहुल्ये" इति वक्ष्यति, तदतत्पुरुषस्य नञ्समासस्य कर्मधारयस्य वा मा भूदिति ॥

(समाधानबाधकभाष्यम्)

नैतदस्ति प्रयोजनम्। नहि च्छायान्तो बाहुल्येऽतत्पुरुषो नञ्समासः कर्मधारयो वास्ति ॥

(प्रदीपः) नहिच्छायान्त इति। पूर्वपदार्थधर्मो बाहुल्यम्, न च षष्ठीतत्पुरुषाद्विना बाहुल्यं गम्यते ॥

(समाधानभाष्यम्)

उत्तरार्थमेव तर्हि "सभा राजाऽमनुष्यपूर्वा" "अशालाच" इति वक्ष्यति। तदतत्पुरुषस्य नञ्समासस्य कर्मधारयस्य वा मा भूदिति ॥

(समाधानबाधकभाष्यम्)

एतदपि नास्ति प्रयोजनम्। नहि सभान्तोऽशालायामतत्पुरुषो नञ्समासः कर्मधारयो वास्ति ॥

(प्रदीपः) नहि सभान्त इति। अशालेति वचनात् संघातवचनः सभाशब्दो ग्राह्यो न च समूहिभिर्विना समूहोपपत्तिरिति षष्ठीतत्पुरुषस्यैव ग्रहणमिति भावः ॥

(उद्द्योतः) न च समूहिभिरिति। तदंशे नित्यसाकाङ्क्षत्वादिति भावः ॥ १९ ॥

(समाधानभाष्यम्)

इदं तर्हि "विभाषा सेनासुरा-" इति वक्ष्यति तदतत्पुरुषस्य नञ्समासस्य कर्मधारयस्य वा मा भूदिति ॥

(प्रदीपः) इदं तर्हीति। अत्र तु प्रदेशे मन्दबुद्ध्यनुग्रहायाधिकारः कृतः ॥ १९ ॥

(आक्षेपभाष्यम्)

तत्पुरुष इति किमर्थम्? ॥

(समाधानभाष्यम्)

दृढसेनो राजा ॥

(आक्षेपभाष्यम्)

असञ्जिति किमर्थम्? ॥

(समाधानभाष्यम्)

असेना ॥

(आक्षेपभाष्यम्)

अकर्मधारय इति किमर्थम्? ॥

(समाधानभाष्यम्)

परमसेना। उत्तमसेना ॥ तत्पुरु० ॥ १९ ॥

(३४७ द्वन्द्वतत्पुरुषलिङ्गानुशासनसूत्रम् ॥२।४।१ आ. १२)

५५७ परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः ॥ २।४।२६ ॥

(सूत्रप्रयोजनाधिकरणम्)

(आक्षेपभाष्यम्)

किमर्थमिदमुच्यते? ॥

(प्रदीपः) परवत्॥ २६॥ द्वन्द्वापेक्षया किमिदं विध्यर्थम्, आहोस्विन्नियमार्थम्। तथा—किं षष्ठीनिर्देशेन समासार्थस्य लिङ्गातिदेशः। अथ सप्तम्याश्रयेण पूर्वपदस्येति संशयानः पृच्छति—किमर्थमिति ॥

(उद्द्योतः) परवल्लिङ्गं ॥ २६ ॥ तत्पुरुषे विधित्वेन चारितार्थ्यसम्भवादाह—द्वन्द्वेति ॥ विध्यर्थमिति। 'अवयवार्थातिरिक्तः समुदायो लिङ्गवान्' इति पक्षे इदम् ॥ नियमार्थमिति। 'उद्भूतावयवभेदः समूहः समासार्थः। स चावयवार्थलिङ्गेनैव लिङ्गवान्' इति पक्षे इदम्। इदं पक्षद्वयं षष्ठ्यन्तत्वपक्षे। सप्तम्यन्तत्वे तु विध्यर्थत्वमेवेति बोध्यम् ॥ इदं द्वन्द्वांशे न समाहारविषयं तस्य विशिष्य नपुंसकत्वविधानात्। किन्तु इतरेतरयोगविषयम् ॥

(समाधानभाष्यम्)

द्वन्द्वोयमुभयपदार्थप्रधानः। तत्र कदाचित्पूर्वस्य यल्लिङ्गं तत्समासस्यापि स्यात्, कदाचिदुत्तरपदस्य, इष्यते च परस्य यल्लिङ्गं तत्समासस्य यथा स्यादिति। तच्चान्तरेण यत्नं न सिध्यतीति "परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः" इत्येवमर्थमिदमुच्यते ॥

(प्रदीपः) द्वन्द्वोयमिति। षष्ठीनिर्देशो नियमश्चेति भावः। तत्रावयवार्थव्यतिरिक्तः समुदायार्थो नास्तीत्युभयपदार्थप्रधान इत्यनेन दर्शितं भवति। तत्र यदापेक्षितपरस्परौ विरुद्धलिङ्गावयवार्थावेव समुदायार्थस्तदा पर्यायेण लिङ्गद्वयप्रसङ्गे नियमार्थमिदं संपद्यते ॥ यद्येवं परस्यैव संबन्धि लिङ्गं क्रियते इति सादृश्याभावाद्वतिनिर्देशो नोपपद्यते। नैष दोषः। केवलाकेवलावस्थाभेदाश्रयेण भेदमाश्रित्य वतिनिर्देशः कृतः ॥

(उद्द्योतः) षष्ठीति। द्वन्द्वतत्पुरुषयोरित्यत्रायं सन्देहः। तत्र षष्ठीपक्षे उद्भूतावयवभेदसमुदायस्य समासार्थत्वात् अवयवभेदकृतवचनवत्तन्निमित्तानेकलिङ्गप्राप्तौ नियमार्थमितीत्याह—नियमश्चेतीति ॥ समुदायार्थो नास्तीति। उद्भूतावयवभेदस्य तस्य द्वन्द्वार्थतया नावयवार्थादत्यन्तातिरिक्तः स इत्यर्थः ॥ अपेक्षितपरस्परावित्यनेन समूहरूपता समासार्थस्योक्ता विरुद्धलिङ्गावयवार्थावित्यनेनोद्भूतावयवभेदता तस्य सूचिता। स चावयवसंख्यावद् अवयवलिङ्गग्राहीतिमते नियमार्थत्वमुक्तम्॥ पर्यायेणेति। विरुद्धलिङ्गा-

समयवद्द्वन्द्वस्थले इत्यर्थः ॥ यद्येवमिति । परस्यैव लिङ्गं न पूर्वस्येत्यर्थाद्वतिनोपपद्यत इति भावः ॥ केवलाकेवलेति । समस्तासमस्तेत्यर्थः ॥

(समाधानशेषभाष्यम्)

तत्पुरुषश्चापि कं प्रयोजयति? । यः पूर्वपदार्थप्रधान एकदेशिसमासः—अर्धपिप्पलीति ॥ यो ह्युत्तरपदार्थप्रधानः, दैवकृतं तस्य परवल्लिङ्गम् ॥

(प्रदीपः) तत्पुरुषापेक्षया विध्यर्थत्वं दर्शयति—**तत्पुरुषश्चापीति** ॥ **दैवकृतमिति** । अयत्नसिद्धमित्यर्थः ॥

(उद्द्योतः) भाष्ये—दैवकृतमिति । उपमितसमासः समानलिङ्गपदयोरेवेति तत्रापि न दोष इति भावः ॥

(अनिष्टापत्तिवारणाधिकरणम्)

(१५७३ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ परवल्लिङ्गं द्वन्द्वतत्पुरुषयोरिति चेत्प्राप्तापन्नालंपूर्वगतिसमासेषु प्रतिषेधः ॥ * ॥

(भाष्यम्) **परवल्लिङ्गं द्वन्द्वतत्पुरुषयोरिति चेत्प्राप्तापन्नालंपूर्वगतिसमासेषु प्रतिषेधो वक्तव्यः ॥ प्राप्तो जीविकां प्राप्तजीविकः । आपन्नो जीविकामापन्नजीविकः ॥ अलंपूर्व—अलं जीविकायै अलंजीविकः ॥ गतिसमास—निष्कौशाम्बिः निर्वाराणसिः ॥**

(१५७४ प्रतिषेधवार्तिकम् ॥ २ ॥)

॥ * ॥ पूर्वपदस्य च ॥ * ॥

(भाष्यम्) **पूर्वपदस्य च प्रतिषेधो वक्तव्यः । मयूरीकुक्कुटौ ॥**

(प्रदीपः) **पूर्वपदस्य चेति** । सप्तमीनिर्देशाश्रयेण दोषोद्भावनम् । तत्र ह्ययमर्थो भवति—द्वन्द्वे तत्पुरुषे च यत्परं तद्वल्लिङ्गं भवति । तत्र कार्यिणोऽनुपादानात्परशब्दस्य संबन्धिशब्दत्वात्तदाक्षिप्तं पूर्वपदमेव कार्यभाक् प्राप्नोति । तत्र **मयूरीकुक्कुटाविति** पूर्वपदस्य पुंस्त्वातिदेशे स्त्रीप्रत्ययनिवृत्तिप्रसङ्गः। **कुक्कुटमयूर्यौ** इत्यत्र स्त्रीप्रत्ययप्रसङ्गः। तथार्धपिप्पलीत्यादावपीति प्रतिषेध उच्यते । पूर्वपदप्रतिषेधे च कृते सामर्थ्याद् द्वन्द्वतत्पुरुषयोरेव कार्यित्वं संपद्यते ॥

(उद्द्योतः) **सप्तमीति** । अवयवषष्ठ्यभिप्रायेणेत्यन्ये ॥ स्त्रीप्रत्ययनिवृत्तीति । अतिदेशविरुद्धत्वात् स्वाश्रयस्यापि निवृत्तिरित्यर्थः ॥ अतिदिश्यमानधर्मप्रयुक्तकार्यविशेषमप्याह—**कुक्कुटेति** ॥ नन्वेवं सूत्रवैयर्थ्यमत आह—**पूर्वपदप्रतिषेधे चेति** ॥

(आशयान्तरेण प्रतिषेधवैयर्थ्यभाष्यम्)

यदि पुनर्यथाजातीयकं परस्य लिङ्गं तथाजातीयकं समासादन्यदतिदिश्यते ॥

(प्रदीपः) **यदि पुनरिति** । षष्ठीनिर्देशो व्यतिरिक्तसमुदायदर्शनं चाश्रीयते । व्यतिरिक्तसमुदायपक्षे हि मुख्यसादृश्योपपत्तिरिति भावः ॥ **समासादन्यदिति** । समासार्थलिङ्गमुपचारात् समासशब्देनोच्यते । तेनोत्तरपदार्थलिङ्गसदृशं समासार्थस्य स्वलिङ्गबाधनाय लिङ्गान्तरमतिदिश्यते इत्युक्तं भवति ॥

(उद्द्योतः) **व्यतिरिक्तसमुदायेति** । तथा च परपदार्थलिङ्गसदृशं लिङ्गं समुदायरूपार्थस्येत्यर्थाद्दस्युपपत्तिरिति भावः ॥ समासात्स्वत एव लिङ्गस्यान्यत्वाद्व्यर्थं विशेषणं समासस्यातिदिश्यत इति च वक्तुं युक्तमत आह—**समासार्थेति** ॥ **स्वलिङ्गबाधनायेति** स्वलिङ्गं च नपुंसकमित्यभिमानः । यदि तु वनं सेना संघ इतिवत्स्यानेकलिङ्गत्वं तदात्रापि पक्षे नियमार्थत्वमेवेति बोध्यम् ॥

(१५७५ आशयान्तरदूषणवार्तिकम् ॥ ३ ॥)

॥ * ॥ समासादन्यल्लिङ्गमिति चेदश्ववडवयोष्टाब्लुग्वचनम् ॥ * ॥

(भाष्यम्) **समासादन्यल्लिङ्गमिति चेदश्ववडवयोष्टापो लुग्वक्तव्यः । अश्ववडवौ ॥**

(प्रदीपः) **अश्ववडवाविति** । परवल्लिङ्गे प्राप्ते पूर्ववदश्ववडवाविति पूर्वपदार्थलिङ्गसदृशं पुंलिङ्गं समासार्थस्य विधीयते न तूत्तरपदार्थस्येति स्त्रीत्वस्यानिवर्तनाट्टापः श्रवणे प्राप्ते लुग्वक्तव्यः ॥

(१५७६ दूषणबाधकवार्तिकम् ॥ ४ ॥)

॥ * ॥ निपातनात्सिद्धम् ॥ * ॥

(भाष्यम्) **निपातनात्सिद्धमेतत् ॥ किं निपातनम्? । "अश्ववडवपूर्वापरेति ॥**

(प्रदीपः) **निपातनादिति** । टाब्रहितस्या रूपमेतदित्यर्थः । **पूर्ववदश्ववडवाविति** निपातनमाश्रयितुं न युज्यते वचनान्तरे पूर्वपदलिङ्गातिदेशप्रसङ्गादश्ववडवानश्ववडवैरिति मत्वा पृच्छति—**किं निपातनमिति** ॥ **अश्ववडवपूर्वापरेति** । अश्ववडवापूर्वापरेति वक्तव्ये टापोऽनुच्चारणं निपातनमित्यश्ववडवयोर्द्वन्द्वे टाब्निवर्तते ॥

(उद्द्योतः) वचनान्तरे इति । द्विवचनविषयत्वेन निपातनस्य तत्साहचर्याल्लिङ्गातिदेशेऽपि तत्रैव स्यादित्यभिमानः ॥

(१५७७ दूषणबाधकान्तरवार्तिकम् ॥ ५ ॥)

॥ * ॥ उपसर्जनह्रस्वत्वं वा ॥ * ॥

(भाष्यम्) **अथ वा "उपसर्जनस्य" इति ह्रस्वत्वं भविष्यति ॥**

(प्रदीपः) **उपसर्जनह्रस्वत्वमिति** । **अनेकमिति** प्रथमानिर्दिष्टत्वात्समुदायार्थेऽवयवार्थस्य गुणभावादुपसर्जनत्वमिति भावः ॥

(उद्योतः) समुदायार्थ इति । इतरेतरयोगेऽपि उद्भूतावयवभेदः समुदाय एव समासार्थ इति भावः ॥

(आक्षेपभाष्यम्)

इहापि तर्हि प्राप्नोति—'कुक्कुटमयूर्यौ' इति ॥

(प्रदीपः) इहापीति । ततश्च कुकुटमयूरी इति प्राप्नोति ॥

(उद्योतः) कुक्कुटमयूरी इति । अन्तरङ्गत्वात्पूर्वं ह्रस्वत्वे कृते दीर्घाद्दितिनिषेधानवतारात्पूर्वसवर्णदीर्घापत्तिरिति भावः। द्वन्द्वे नेति निषेधे तु अश्ववडवेत्यत्रापि तदनापत्तिरिति तात्पर्यम् ॥

(इष्टापत्तिभाष्यम्)

अस्तु ॥

(१५७८ व्याख्यान्तरवार्तिकम् ॥ ६ ॥)

॥*॥ परवल्लिङ्गमिति शब्दशब्दार्थौ ॥*॥

(भाष्यम्) **परवल्लिङ्गमिति शब्दशब्दार्थावतिदिश्येते । तत्रौपदेशिकस्य ह्रस्वत्वम् । आतिदेशिकस्य श्रवणं भविष्यति ॥**

(प्रदीपः) शब्दशब्दार्थाविति । लिङ्गशब्देन लिङ्गाभिधायी प्रत्ययोऽर्थश्चात्र तन्त्रेणैकशेषेण वोच्यत इत्यर्थः ॥ आतिदेशिकस्य श्रवणमिति । तस्यानुपसर्जनत्वात्तदन्तस्य चाप्रातिपदिकत्वाद् ह्रस्वाभावात् ॥

(उद्योतः) तस्यानुपसर्जनत्वादिति । समुदायात्तस्यातिदेशादित्यर्थः । अत एव तदन्तस्याप्रातिपदिकत्वमपि बोध्यम् । अयं हेतुर्लिङ्गविशिष्टलिङ्गिभावासत्त्वाच्चिन्त्यः ॥

(आक्षेपान्तरभाष्यम्)

इदं तर्हि—दत्ता च कारीषगन्ध्या च दत्ताकारीषगन्ध्ये । दत्ता च गार्ग्यायणी च दत्तागार्ग्यायण्यौ । द्वौ ष्यङौ द्वौ ष्फौ च प्राप्नुतः ॥

(प्रदीपः) द्वौ ष्यङाविति । तत्र यस्येति चेत्याकारलोपे कृते द्वौ यकारौ श्रूयेयाताम् । हलो यमामिति विकल्पितो लोपः । यद्यपि यणो मय इति द्विर्वचनेनात्र भाव्यं तथापि पक्षे यकारत्रयश्रवणप्रसङ्गः ॥

(उद्योतः) यकारत्रयश्रवणेति । न च पुनर्द्वित्वप्रवृत्त्या तदपि इष्टमेव, लक्ष्ये लक्षणस्य सकृत्प्रवृत्त्या पुनर्द्वित्वाप्रवृत्तेरिति भावः ॥

(इष्टापत्तिभाष्यम्)

स्ताम् । पुंवद्भावेनैकस्य निवृत्तिर्भविष्यति ॥

(प्रदीपः) पुंवद्भावेनेति । भस्याढे तद्धित इत्यनेनेति भावः ॥

(उद्योतः) भस्याढइति । ष्यङ्ष्फयोस्तद्धितत्वादिति भावः॥

(आक्षेपभाष्यम्)

इदं तर्हि—दत्ता च युवतिश्च दत्तायुवती । द्वौ तिशब्दौ प्राप्नुतः ॥

(प्रदीपः) द्वौ तिशब्दाविति । अत्र ह्यभत्वान्नास्ति पुंवद्भावः ॥

(उपसंहारभाष्यम्)

तस्मान्नैतच्छक्यं वक्तुं 'शब्दशब्दार्थावतिदिश्येते' इति ॥

(प्रदीपः) तस्मान्नैतदिति । उपसर्जनह्रस्वत्वं तु न भवत्यन्वर्थसंज्ञाविज्ञानादप्रधानस्योपसर्जनसंज्ञाविधानात्सकलपदार्थप्रधानत्वाच्च द्वन्द्वस्य । व्यतिरिक्तसमुदायरूपद्वन्द्वार्थाभ्युपगमेऽपि अवयवानां कार्यसंबन्धात् फलतः प्राधान्यमेव ॥

(उद्योतः) अन्वर्थेति । अप्रधानस्यैव प्रथमानिर्दिष्टस्योपसर्जनसंज्ञाविधानादित्यर्थः । अवयवानां कार्यसम्बन्धादिति । व्यक्त्याकृत्योरिव समाहारसमाहारिणोरभेदेनेति भावः ॥ अन्वर्थत्वानङ्गीकारे तु ह्रस्वविधायके *द्वन्द्वे नेतिवचनकरणान्न दोष इति भावः ॥

(आक्षेपस्मारणभाष्यम्)

ननु चोक्तं *समासादन्यल्लिङ्गमिति चेदश्ववडवयोष्टाब्लुग्वचनम्* इति ॥

(समाधानभाष्यम्)

परिहृतमेतत्—*निपातनात्सिद्धम्* इति ॥

(समाधानान्तरभाष्यम्)

अथ वा नैवं विज्ञायते—परस्यैव परवदिति । कथं तर्हि ? । परस्येव परवदिति । यथाजातीयकं परस्य लिङ्गं तथाजातीयकं समासस्यातिदिश्यते । अथ पूर्वपदस्य न प्रतिषिध्यते ॥

(प्रदीपः) अथ वेति । नायं नियमः, किं तु विधिरित्यर्थः ॥ परस्यैवेति । एवशब्दप्रयोगेण नियमं निषेधाय दर्शयति । न त्वेवार्थे वतिर्विहितः । यथा च नियमपक्षे वतिरुपपद्यते तथा पूर्वमेव प्रतिपादितम् ॥ इह त्रीणि दर्शनानि— अवयवावपेक्षितपरस्परौ द्वन्द्वार्थः, न तु व्यतिरिक्तः समुदायोस्ति । अत्र दर्शने नियमार्थमिदम् ॥ अवयवार्थव्यतिरिक्तो वा समुदायो द्वन्द्वार्थः स चावयवलिङ्गैनैव लिङ्गवानित्यत्रापि दर्शने पर्यायेण लिङ्गप्राप्तौ वचनं नियमार्थम् ॥ यदा तु समुदायो द्वन्द्वार्थः स चालिङ्ग इति दर्शनं तदा विध्यर्थमिदम् ॥ अथ पूर्वपदस्येति । अंतः पूर्वपदस्येत्यर्थः । एतेन मयूरीकुक्कुटाविति परिहृतं षष्ठ्याश्रयेण दर्शनत्रयेऽपि ॥ मध्यमे तु दर्शने आश्रयभेदाल्लिङ्गभेदाश्रयेण परवदिति सादृश्याश्रयो वतिः ॥

(उद्योतः) ननु तद्व्यतिरिक्त इति । अत्यन्तं व्यतिरिक्त एवेत्यर्थः । अतएव अपेक्षितपरस्पराविति सङ्गच्छते । अनेन समूहरूपतावयवयोः सूच्यते । अतएव पक्षत्रये बोधाविशेषः । अन्यथा

फलभेदः स्यात् ॥ एतेनायं कैयटः साहित्यमितरेतरयोगे विशेषणमित्येवं पर इति वदन्तः परास्ताः ॥ **नियमार्थमिति ।** पर्यायेण लिङ्गद्वयप्राप्ताविति भावः ॥ **अवयवार्थव्यतिरिक्तो वेति ।** व्यतिरिक्त एवेत्यर्थः ॥ **स चावयवलिङ्गेनेति ।** अवयवसंख्यया संख्यावानित्यपि बोध्यम् ॥ **स चालिङ्ग इति ।** उद्भूतावयवभेदत्वेऽपि तल्लिङ्गत्वे मानाभाव इति भावः ॥ नपुंसकलिङ्ग इति वक्तुमुचितम् ॥ **अथवेत्यादि** भाष्यं च **यदि पुनर्यथाजातीयमित्यादिनो**कार्थस्यैवानुवादपरमिति बोध्यम् । **यदि पुनरित्यादिग्रन्थस्यापि** विधिपरत्वात् । **स्वलिङ्गबाधनायेति** व्याचक्षाणेनोपाध्यायेन विधित्वमुक्तमायमेव ॥ अन्येतु **यदि पुनरितिभाष्यस्य समासस्येति**पदकर्त्तव्यतापरता, द्वन्द्वतत्पुरुषयोरिति पदावृत्तिपरता वा, अथवेत्यादेश्च तत्प्रत्याख्यानपरतेति वदन्ति ॥ **अतः पूर्वपदस्येति ।** अप्राप्तेरित्यर्थः ॥ **आश्रयभेदादिति ।** समुदायरूपस्य केवलस्य चाश्रयस्य भेदादित्यर्थः ॥ [एषु दर्शनत्रयेषु आद्य 'उभयपदार्थप्रधानः' इति भाष्यसंमत एव, विधित्वपरभाष्यसंमतोऽ्योपि ॥] मध्येतु पक्षे भाष्यानुग्रहश्चिन्त्यः ॥

(आक्षेपभाष्यम्)

प्रासादिषु कथम् ? ॥

(१५७९ समाधानवार्तिकम् ॥ ७ ॥)

॥ * ॥ प्रासादिषु चैकदेशिग्रहणात्सिद्धम् ॥ * ॥

(भाष्यम्) **'द्वन्द्वैकदेशिनोः' इति वक्ष्यामि ॥**

(आक्षेपभाष्यम्)

तदेकदेशिग्रहणं कर्तव्यम् ? ॥

(समाधानभाष्यम्)

न कर्तव्यम् । एकदेशिसमासो नारभ्यते ॥

(प्रदीपः) **एकदेशिसमासो नारभ्यत इति ।** **पूर्वापराधरेति** योगत्रयं नारभ्यते । **परवल्लिङ्गं द्वन्द्वस्ये**स्येतावच्च क्रियते सूत्रमित्यर्थः ॥

(उद्द्योतः) एकदेशिसमासानारम्भेऽपीह तत्पुरुषग्रहणे प्रासादिषु दोषस्तदवस्थोऽत आह—**द्वन्द्वस्येत्येतावदिति** ॥

(आक्षेपभाष्यम्)

कथमर्धपिप्पलीति ? ॥

(समाधानभाष्यम्)

समानाधिकरणो भविष्यति—अर्धं च सा पिप्पली च अर्धपिप्पलीति ॥

(प्रदीपः) **अर्धं च सा पिप्पली चेति ।** अवयवे समुदायोपचारात्सामानाधिकरण्यम् । तत्रोत्तरपदार्थस्य प्राधान्यात्तदीयमेव लिङ्गं तत्पुरुषस्यापि भवतीति नार्थस्तत्पुरुषग्रहणेनेत्यर्थः ॥

(समाधानबाधकभाष्यम्)

न सिध्यति । परत्वात्षष्ठीसमासः प्राप्नोति ॥

(प्रदीपः) **परत्वादिति ।** अयमर्थः—

'नर्ते प्रयोजनादिष्टं मुख्यशब्दार्थलङ्घनम्'

इति भेदाश्रयणमेव **परं** मुख्यं प्रधानम् । ततश्च **षष्ठीसमास एव प्राप्नोति** भिन्नविषयत्वात्तु शास्त्रापेक्षं परत्वमत्र न विवक्षितम् ॥

(उद्द्योतः) भेदविवक्षायां षष्ठीसमासस्य अभेदे समानाधिकरणसमासस्येति विषयभेदात्परत्वादित्यनुपपन्नमत आह—**अयमर्थ** इति । एवंच परत्वादित्यस्योत्कृष्टत्वादित्यर्थ इति भावः ॥

(षष्ठीसमासासंभवभाष्यम्)

अद्य पुनरयमेकदेशिसमास आरभ्यमाणः षष्ठीसमासं बाधते ॥

(षष्ठीसमासेष्टापत्तिभाष्यम्)

इष्यते च षष्ठीसमासोपि । तद्यथा—अपूपार्धं मया भक्षितं ग्रामार्धं मया लब्धमिति । एवं पिप्पल्यर्धमित्यपि भवितव्यम् ॥

(आक्षेपभाष्यम्)

कथमर्धपिप्पलीति ? ॥

(समाधानभाष्यम्)

समानाधिकरणो भविष्यति ॥ परवल्लिङ्गम् ॥ २६ ॥

(प्रदीपः) **समानाधिकरणो भविष्यतीति ।** एवमादिप्रयोगसिद्धिरेवोपचाराश्रयणस्य प्रयोजनम् । **मुनिद्वयाच्च** भाष्यकारः प्रमाणतरमधिकलक्ष्यदर्शित्वात् ॥ २६ ॥

(उद्द्योतः) **एवमादीति ।** भेदाश्रयणस्य मुख्यत्वेऽपीदृशप्रयोगसिद्ध्यर्थमेवोपचाराश्रयणमिति भावः ॥ **मुनिद्वयाच्चेति ।** एवं च सूत्रत्रयविषयेऽपि षष्ठीसमासस्य साधुत्वे कर्मधारयस्य चेति भावः ॥ **पिप्पल्यर्धमित्यपीत्यपिना** सूत्रत्रयोदाहरणसंग्रहो बोध्यः ॥ २६ ॥

(३४८ पुंलिङ्गसूत्रम् ॥ २ । ४ । १ आ. १३)

५६० रात्राह्नाहाः पुंसि ॥ २।४।२९ ॥

(शेषपूरणाधिकरणम्)

(१५८० शेषवार्तिकम् ॥ १ ॥)

॥ * ॥ अनुवाकादयः पुंसि ॥ ॥ * ॥

(भाष्यम्) **अनुवाकादयः पुंसि भाष्यन्त इति वक्तव्यम् । अनुवाकः । शंयुवाकः ॥ रात्रा ॥ २९ ॥**

(प्रदीपः) **रात्रा ॥ २९ ॥ अनुवाक इति ।** अनूच्यत इत्यनुवाकस्तत्र विशिष्टं वाक्यमभिधेयमिति नपुंसकत्वे प्राप्ते वचनम् ॥ २९ ॥

(उद्द्योतः) रात्राह्ना ॥ २९ ॥ अनुवाकादय इति । अनुवाको वाक्यमिति प्रयोगसिद्धये इदमित्याह—तत्र विशिष्टमिति ॥ २९ ॥

(३४९ नपुंसकसूत्रम् ॥ २ । ४ । १ आ. १४)

५६१ अपथं नपुंसकम् ॥ २।४।३० ॥

(शेषपूर्त्यधिकरणम्)

(१५८१ शेषवार्तिकम् ॥ १ ॥)

॥ * ॥ पुण्यसुदिनाभ्यामह्नः ॥ * ॥

(भाष्यम्) पुण्यसुदिनाभ्यामह्नो नपुंसकत्वं वक्तव्यम् । पुण्याहम् । सुदिनाहम् ॥

(प्रदीपः) अपथम् ॥ ३० ॥ पुण्याहमिति । रात्राह्नाहाः पुंसीति प्राप्ते वचनम् ॥ सुदिनाहमिति । सुदिनशब्दोऽत्र प्रशंसामात्रवाची । तेन दिनाहःशब्दयोर्युगपद्विरुद्धः प्रयोगः । दृश्यते च प्रशंसार्थस्य प्रयोगः—

"सुदिनासु समासु कार्यमेतत् प्रविचिन्वीत विशेषतः स्वयं च" इति ॥

(उद्द्योतः) अपथं नपुंसकम् ॥ ३० ॥ उत्तरपदार्थप्राधान्यात्परवल्लिङ्गत्वात् सूत्रेणैव सिद्धमत आह—रात्राह्नाहा इति ॥

(१५८२ शेषवार्तिकम् ॥ २ ॥)

॥ * ॥ पथः संख्याव्ययादेः ॥ * ॥

(भाष्यम्) पथः संख्याव्ययादेरिति वक्तव्यम् ॥ द्विपथं त्रिपथं चतुष्पथम् उत्पथं विपथम् ॥

(प्रदीपः) चतुष्पथमिति । षष्ठीतत्पुरुषः । समाहारद्विगौ तु द्विगुश्चेति सिद्धमेव नपुंसकत्वम् ॥ उत्पथमिति । कुगतिप्रादय इति तत्पुरुषः । अव्ययादित्वादपथशब्दस्य नपुंसकत्वे सिद्धे किं सूत्रेणेति चेत्, पूर्वकालत्वात् सूत्रस्य नायं दोषः ॥

(उद्द्योतः) पथः संख्येति वार्तिके कृतसमासान्तपथिन्शब्दस्यैव ग्रहणं साहचर्यादिति बोध्यम् । तेनातिपन्था इत्यादौ न दोषः । सत्पथ इत्यादौ तु स्वतिभ्यामेवेति नियमात्समासान्तोऽस्त्येव । तदेव संख्याव्ययादेरित्यस्य व्यावर्त्यमित्याहुः ॥ पूर्वकालत्वादिति । सूत्रप्रत्याख्यानपरमेव वार्तिकमिति भावः ॥

(१५८३ शेषवार्तिकम् ॥ ३ ॥)

॥ * ॥ द्विगुश्च ॥ * ॥

(भाष्यम्) द्विगुश्च समासो नपुंसकलिङ्गो भवतीति वक्तव्यम् । पञ्चगवं दशगवम् ॥

(प्रदीपः) द्विगुश्च समास इति । स नपुंसकमित्यस्यानन्तरप्रक्रान्तो द्वन्द्व एव स इत्यनेन परामृश्यते इति द्विगोरप्राप्तं नपुंसकत्वमिति वचनम् । यथा सामन्त्रितमित्यत्र संबोधनप्रथमैव परामृश्यते । समाहारद्विगोश्चेह ग्रहणं न तु तद्धितार्थद्विगोः ॥ पञ्चगवमिति । यदा पञ्च गावः समाहृता इत्यत्रार्थे द्विगुस्तदोत्तरपदार्थस्य प्राधान्यात्तदीयं लिङ्गं प्राप्नोति । यदा तु समूहोऽभिधेयस्तदा तस्य वनं सेना संघ इत्यादिवदनियतलिङ्गत्वं प्राप्तमिति वचनम् ॥

(उद्द्योतः) द्विगोरप्राप्तमिति । वस्तुतो व्यवहितद्विगुग्रहणस्य तत्र सम्बन्धबोधकमिदम् ॥ सम्बोधनप्रथमैवेति । न प्रथमामात्रमित्यर्थः ॥ समाहारद्विगोश्चेति । समूहसमूहिनोरत्यन्तभेदाभावात्स्वपदार्थप्रधानत्वेनान्तरङ्गत्वाद्व्याख्यानाच्च तस्यैव ग्रहणमिति भावः ॥ यदा पञ्च गाव इति । अयं पक्षस्तु तत्रैव भाष्ये दूषितः ॥ चार्थबोधकसमाहारपदेऽपि कर्मसाधनतापत्तौ बहूपद्रव इति चिन्त्यमेतत् ॥

(१५८४ शेषवार्तिकम् ॥ ४ ॥)

॥ * ॥ अकारान्तोत्तरपदो द्विगुः स्त्रियाम् ॥ * ॥

(भाष्यम्) अकारान्तोत्तरपदो द्विगुः स्त्रियां भाष्यत इति वक्तव्यम् । पञ्चपूली दशपूली ॥

(१५८५ शेषवार्तिकम् ॥ ५ ॥)

॥ * ॥ वाबन्तः ॥ * ॥

(भाष्यम्) वा आबन्तः स्त्रियां भाष्यत इति वक्तव्यम् । पञ्चखट्वी पञ्चखट्वम् । दशखट्वी दशखट्वम् ॥

(प्रदीपः) पञ्चखट्वीति । टाप उपसर्जनह्रस्वत्वे कृते द्विगोरिति ङीप् । यदा तु समूहोऽभिधेयस्तदोपसर्जनह्रस्वत्वं सिध्यति न तु समाह्रियमाणेऽभिधेये इति तत्रैव सूत्रे उक्तम् । पञ्चखट्वमित्यत्र त्वसत्युपसर्जनत्वे नपुंसकह्रस्वत्वं सिध्यति । उपसर्जनत्वे तु परत्वात्तदाश्रयं ह्रस्वत्वम् ॥

(उद्द्योतः) कृते इति । अन्यथादन्तत्वाभावान्न स्यादिति भावः ॥ न तु समाह्रियमाण इति । एवं च कर्मसाधनव्युत्पत्तिरसङ्गतेति तामवष्टभ्य स्त्रियां पञ्चखट्वीत्यपि रूपमिति न वाच्यमिति बोध्यम् ॥ परत्वादिति । यौगपद्यासंभवरूपविरोधाभावाच्चिन्त्यमिदम् ॥

(१५८६ शेषवार्तिकम् ॥ ६ ॥)

॥ * ॥ अनो नलोपश्च ॥ * ॥

(भाष्यम्) अनो नलोपश्च वा च स्त्रियां भाष्यत इति वक्तव्यम् । पञ्चतक्षी पञ्चतक्षम् ॥

(प्रदीपः) अनो नलोपश्चेति । चशब्देन 'वा स्त्रियां भाष्यते' इति समुच्चीयते । नलोपस्तु नित्यमेव क्रियते । उत्तरपदत्वे चापदादिविधाविति प्रत्ययलक्षणनिषेधात्पदत्वाभावान्नलोपो न प्राप्नोतीति वचनम् ॥

(उद्द्योतः) सन्नियोगशिष्टत्वे पञ्चतक्षमित्युदाहरणानुपपत्तिरत आह—चशब्देनेति ॥ नलोपः प्रातिपदिकेति नलोपसिद्धिमाशङ्क्याह—उत्तरेति ॥

(१५८७ शेषवार्तिकम् ॥ ७ ॥)

॥ * ॥ पात्रादिभ्यः प्रतिषेधः ॥ * ॥

(भाष्यम्) पात्रादिभ्यः प्रतिषेधो वक्तव्यः । पञ्चपात्रं द्विपात्रम् ॥ ३० ॥

(प्रदीपः) पात्रादिभ्य इति । तादर्थ्ये चतुर्थीयम् । आकृतिगणश्च पात्रादिः ॥ ३० ॥

(उद्द्योतः) तादर्थ्ये इति । पात्रान्तादिप्रयोगसिद्ध्यर्थमित्यर्थः । अत एव वृद्धिसूत्रे सूत्रशब्दस्य पात्रादित्वे कैयटसंमतेऽपि न त्रिसूत्रीत्यादिप्रयोगविरोध इति बोध्यम् ॥ ३० ॥

(३५० पुंनपुंसकलिङ्गसूत्रम् ॥ २ । ४ । १ आ. १५ ॥)

५६२ अर्धर्चाः पुंसि च ॥ २।४।३१ ॥

(बहुवचनस्याद्यर्थकत्वाधिकरणम्)

(१५८८ वार्तिकम् ॥ १ ॥)

॥ * ॥ अर्धर्चादयः ॥ * ॥

(भाष्यम्) अर्धर्चादय इति वक्तव्यम् । अर्धर्चः अर्धर्चम् । कार्षापणं कार्षापणः । गोमयं गोमयः । सरकं सरकः ॥

(प्रदीपः) अर्धर्चाः ॥ ३१ ॥ कार्षापणादिसंग्रहायाह—अर्धर्चादय इति वक्तव्यमिति ॥

(आक्षेपभाष्यम्)

तत्तर्हि वक्तव्यम् ? ॥

(समाधानभाष्यम्)

न वक्तव्यम् ॥

(१५८९ समाधानसाधकवार्तिकम् ॥ २ ॥

॥ * ॥ बहुवचननिर्देशात्सिद्धम् ॥ * ॥

(भाष्यम्) बहुवचननिर्देशादाद्यर्थो गम्यते ॥ अर्धर्चाः ॥ ३१ ॥

(प्रदीपः) बहुवचननिर्देशात्सिद्धमिति । साहचर्यादर्धर्चशब्देनान्येषामभिधानात् ॥ ३१ ॥

(इति लिङ्गानुशासनम्)

(इति विधिशेषप्रकरणम्)

(अथ विधिप्रकरणम्)

(३५१ आदेशविधिसूत्रम् ॥ २ । ४ । १ आ. १६ ॥)

५६३ इदमोऽन्वादेशेऽशनुदात्तस्तृतीयादौ ॥ २।४।३२ ॥

(अन्वादेशलक्षणाधिकरणम्)

(१५९० वार्तिकम् ॥ १ ॥)

॥ * ॥ अन्वादेशे समानाधिकरणग्रहणम् [देवदत्तं भोजयेमं चेत्यप्रसङ्गार्थम्] ॥ * ॥

(भाष्यम्) अन्वादेशे समानाधिकरणग्रहणं कर्तव्यम् ॥ किं प्रयोजनम् ? । देवदत्तं भोजय इमं चेत्यप्रसङ्गार्थम् । इह मा भूत्—देवदत्तं भोजय इमं च यज्ञदत्तं भोजयेति ॥

(प्रदीपः) इदमो ॥ ३२ ॥ पश्चात्कथनमात्रमन्वादेशः प्रसिद्ध इति व्यधिकरणप्रसङ्गनिवारणायाह—अन्वादेशे इति ॥ इमं चेति । एनादेशः प्राप्तो निवार्यते ॥

(उद्द्योतः) इदमोन्वा ॥ ३२ ॥ कथितानुकथनस्यान्वादेशत्वे वार्त्तिकानुत्थानादाह—पश्चादिति ॥ तृतीयादौ विहितादेशस्य द्वितीयादावप्रसक्तेराह—एनादेश इति । सूत्रत्रयस्याप्यन्वादेशविषयत्वादित्यर्थः ॥ एवं च समानाधिकरणग्रहणेन कथितानुकथनमेवान्वादेश इति बोध्यते ॥

(१५९१ अन्वादेशलक्षणवार्तिकम् ॥ २ ॥)

॥ * ॥ अन्वादेशश्च कथितानुकथितमात्रम् ॥ * ॥

(भाष्यम्) अन्वादेशश्च कथितानुकथितमात्रं द्रष्टव्यम् । तद् द्वेष्यं विजानीयाद्-इदमा कथितमिदमैव यदानुकथ्यत इति । तदाचार्यः सुहृद्भूत्वान्वाचष्टे-अन्वादेशश्च कथितानुकथितमात्रमिति ॥

(प्रदीपः) अन्वादेशश्चेति । प्रत्यासत्त्येदमैव कथितं यदानुकथ्यते तेनैव तदान्वादेशो भवतीति भ्रान्तिनिवारणाय वार्तिकम् । तत्र समानाधिकरणग्रहणाच्छब्दान्तरेणेदमा वा कथितं यदाऽनु कथ्यते तदान्वादेशो भवति ॥ द्वेष्यमिति । विपरीतत्वादनभिमतमेत्रेत्यर्थः ॥

(उद्द्योतः) एवं चोत्तरवार्त्तिकं व्यर्थमत आह—प्रत्यासत्त्येति ॥ तदेवाह—भाष्ये—तद्द्वेष्यमिति । तथा च प्रत्यासत्त्यर्थं वार्त्तिककृता वार्त्तिकान्तरेण व्याख्यातमिति भावः ॥ कथितमित्यस्याघातं सत्कथितमित्यर्थः । तेनैतमात्रमित्यादौ नादेश इति बोध्यम् ॥

(आदेशशित्करणप्रयोजनाधिकरणम्)

(आक्षेपभाष्यम्)

अथ किमर्थमशादेशः क्रियते, न 'तृतीयादिषु' इत्येवोच्येत । तत्र डायामोसि च एनेन भवितव्यम् । अन्याः सर्वा हलादयो विभक्तयः । तत्र इद्रूपलोपे कृते केवलमिदमोनुदात्तत्वं वक्तव्यम् ॥

(समाधानभाष्यम्)

अत उत्तरं पठति—

(१५९२ प्रयोजनवार्तिकम् ॥ ३ ॥)

॥ * ॥ अशादेशवचनं साकच्कार्थम् ॥ * ॥

(भाष्यम्) अशादेशवचनं साकच्कार्थं क्रियते। साकच्कस्यायमादेशो यथा स्यात्—इमकाभ्यां रात्रिरधीता अथो आभ्यामहरप्यधीतमिति ॥

(प्रदीपः) साकच्कार्थमिति। साकच्कस्येद्रूपलोपो नास्त्यक इत्यधिकारात्। नापि चेद्रूपलोपेनाभ्यामित्यादि सिध्यति ॥

(उद्द्योतः) नापि चेति। अभ्युपेत्यवादेनेदम्। भाष्ये रात्रिरधीतेति। द्रव्यकर्मणाऽविवक्षितत्वात्कालकर्मणि क्तः। सम्बन्धस्याविवक्षणादत्यन्तसंयोगाविवक्षणाद्वा षष्ठ्यपवादः कालाध्वनोरिति द्वितीया न कृता ॥

(आक्षेपभाष्यम्)

अथ किमर्थं शित्करणम्? ॥

(१५९३ समाधानवार्तिकम् ॥ ४ ॥)

॥ * ॥ शित्करणं सर्वादेशार्थम् ॥ * ॥

(भाष्यम्) शित्करणं क्रियते सर्वादेशार्थम्। शित्सर्वस्येति सर्वादेशो यथा स्यात्—इमकाभ्यां छात्राभ्यां रात्रिरधीता, अथो आभ्यामहरप्यधीतमिति। अक्रियमाणे हि शित्करणेऽलोन्त्यस्य विधयो भवन्तीत्यन्त्यस्य प्रसज्येत ॥

(१५९४ समाधानबाधकवार्तिकम् ॥ ५ ॥)

॥ * ॥ न वान्त्यविकारवचनानर्थक्यात् ॥ * ॥

(भाष्यम्) न वा वक्तव्यम् ॥ किं कारणम्?। अन्त्यस्य विकारवचनानर्थक्यात्। अकारस्याकारवचने प्रयोजनं नास्तीति कृत्वान्तरेणापि शकारं सर्वादेशो भविष्यति ॥

(प्रदीपः) अन्त्यस्येति। त्यदादित्वादकारस्येत्यर्थः ॥

(उद्द्योतः) मकारस्यादेशे विकारवचनानर्थक्यानुपपत्तिरित्याह—त्यदादित्वादिति। परत्वात्त्यदाद्यत्वं मन्यते ॥

(१५९५ समाधानसाधकवार्तिकम् ॥ ६ ॥)

॥ * ॥ अर्थवत्त्वादेशप्रतिषेधार्थम् [तस्माच्छित्करणम्] ॥ * ॥

(भाष्यम्) अर्थवद्धकारस्याकारवचनम्॥ कोऽर्थः?। आदेशप्रतिषेधार्थम्। येऽन्ये अकारस्यादेशाः प्राप्नुवन्ति तद्बाधनार्थम्। तद्यथा—"भो राजि समःक्वौ" इति मकारस्य मकारवचने प्रयोजनं नास्तीति कृत्वा अनुस्वारादयो बाध्यन्ते। तस्माच्छित्करणम्। तस्माच्छकारः कर्तव्यः ॥

(उद्द्योतः) भाष्ये—येऽन्ये इति। दीर्घत्वादयः पररूपं चेत्यर्थः ॥ भाष्ये—अनुस्वारादय इति। प्रशाम्ब्रलयतीत्यादौ मो नो धातोरिति नत्वाभाव आदिशब्दार्थः ॥

(एकदेशिसमाधानबाधकभाष्यम्)

न कर्तव्यः। प्रश्लिष्टनिर्देशोयम्—'अ अ' "अनेकाल्शित्सर्वस्य" इति सर्वादेशो भविष्यति ॥

(प्रदीपः) अ अ इति। समुदायाद्विभक्तिरर्थवत्त्वाद्भवति। ततोऽकारस्यापदान्तत्वादतो गुण इति पररूपं क्रियते। तत्रादेशप्रवृत्तिकाले समुदायः अ अ इति प्रवर्तते। तत्रानेकाल्त्वात्सर्वादेशे प्रवृत्ते पररूपं प्रवर्तते ॥

(उद्द्योतः) अअ इति निर्देशे विपरीतं गौरवमत आह—समुदायादिति। तस्याः सुपां सुलुगिति लुक् ॥ वस्तुतः सौत्रत्वाद्विभक्त्यनुत्पत्तिरेव वक्तुमुचिता ॥ कृतैकादेशस्यादेशत्वे विवक्षितासिद्धिरत आह—तत्रेति। कृतैकादेशनिर्देशसामर्थ्यादिति भावः ॥ अत्र न कर्तव्य इत्यादिरेकदेश्युक्तिः व्याख्यानसापेक्षत्वात्प्रक्रियागौरवाच्च शकारस्यैव लघुत्वात् ॥

(समाधानबाधकभाष्यम्)

अथ वा विचित्रास्तद्धितवृत्तयः। नान्वादेशेऽकुत्पद्यते ॥ इदमो ॥ ३२ ॥

(प्रदीपः) अथ वेति। आदेशस्यैव प्रत्याख्यानं क्रियते अनुदात्तत्वमात्रमेव विधेयमित्यर्थः ॥ नान्वादेश इति। महाविभाषाधिकाराद्व्यवस्थितविभाषाविज्ञानात्। किंचाकचि कृतेनेन चाशादेशे कृतेऽज्ञातार्द्यर्थगतिः प्रकरणाद्यधीना तद्वरमनुत्पत्तिरेवाकचोऽस्तु। एवं ह्यादेशो न विधातव्यो भवति ॥ ३२ ॥

(उद्द्योतः) व्यवस्थितेति। अयमेव भाष्ये—वैचित्र्यशब्दार्थ इति भावः। वस्तुतो अभिधानलक्षणाः कृत्तद्धितसमासा इत्यकर्त्तरि चेति सूत्रभाष्योक्तेरनभिधानादकज्नेत्येव भाष्यार्थः ॥ किञ्चेति। निष्फलमप्यन्वादेशेऽकज्विधानमिति भावः ॥ किंचेत्याद्यपि चिन्त्यम्—तदर्थं कुत्सितपदघटितस्याकच्घटितस्य वा साधुत्वेन तदुत्पत्तिपूर्वकमादेशस्यैवावश्यकत्वात्। अनभिधाने तु नास्ति दोषः कुत्सिताभ्यामाभ्यामित्यर्थस्य वाक्यैकदेशन्यायेन बोधादित्याहुः ॥ ३२ ॥

(३५२ आदेशसूत्रम् ॥ २। ४। १ आ. १७)

५६४ एतदस्त्रतसोस्त्रतसौ चानुदात्तौ ॥ २।४।३३ ॥

(अनुदात्तत्वकथनप्रयोजनाधिकरणम्)

(आक्षेपभाष्यम्)

किमर्थं त्रतसोरनुदात्तत्वमुच्यते? ॥

(प्रदीपः) एतदः ॥ ३३ ॥ अत्रात इत्यत्र त्रलतसिलोः कृतयोः प्रकृतेर्लित्स्वरे कृते शेषनिघातेन प्रत्ययानुदात्तत्वे सत्यशनुदात्तः करिष्यते तत्रैतदस्त्रतसोरित्येतावत् सूत्रं कर्तव्यमिति प्रश्नः—किमर्थमिति ॥

(उद्योतः) एतदस्त्रत ॥ ३३ ॥ तद्विनापि सर्वानुदात्तत्वसिद्धिं दर्शयति—अत्रेति ॥ अनेन भाष्येऽग्रे—'लित्स्वरे' इत्यस्य 'प्रकृतेः प्रत्ययनिमित्तके' इत्यादि, 'निघाते' इत्यस्य 'प्रत्ययस्येत्यादिः 'एतदोऽनुदात्तत्वेन' इत्यत्र 'एतदित्यस्याशः' इति शेष इति दर्शयति ॥ अन्यथैतद आदेशेनापहारात्तस्यानुदात्तत्वासंभव इति बोध्यम् ॥

(समाधानभाष्यम्)

उदात्तौ मा भूतामिति ॥

(प्रदीपः) **उदात्ताविति** । प्रत्ययस्वरेण ॥

(समाधानबाधकभाष्यम्)

नैतदस्ति प्रयोजनम् । लित्स्वरे निघाते एतदनुदात्तत्वेन सिद्धम् ॥

(उद्योतः) एतदोऽनुदात्तत्वेनेति क्वचित्पाठः । तद्वाऽशनुदात्तत्वेनेत्यर्थः ॥

(समाधानसाधकभाष्यम्)

इदमिह संप्रधार्यम्—अनुदात्तत्वं क्रियताम्, लित्स्वर इति । किमत्र कर्तव्यम्?। परत्वाल्लित्स्वरः॥ नित्यमनुदात्तत्वम्—कृतेपि लित्स्वरे प्राप्नोति, अकृतेपि । तत्र नित्यत्वादनुदात्तत्वे कृते लिति पूर्व उदात्तभावी नास्तीति कृत्वा यथाप्राप्तः प्रत्ययस्वरः प्रसज्येत । तद्यथा—'गोष्पदप्रं वृष्टो देवः' ऊलोपे कृते पूर्व उदात्तभावी नास्तीति कृत्वा यथाप्राप्तः प्रत्ययस्वरो भवति । तस्मात्त्रतसोरनुदात्तत्वं वक्तव्यम् ॥ एतदः ॥ ३३ ॥

(प्रदीपः) **नित्यमिति** । लित्स्वरस्त्वनुदात्तत्वे कृते न प्रवर्तते । अनुदात्तविधानसामर्थ्यात् । एतच्चोत्सर्गापवादभावमनपेक्ष्योक्तम् ॥ **लिति पूर्व इति** । औपश्लेषिकाधिकरणविवक्षायां सप्तमी । **उपपदविभक्तेः कारकविभक्तिर्बलीयसीति** दिग्योगलक्षणपञ्चम्यभावः ॥ **प्रत्ययस्वरः प्रसज्येतेति** । अपवादाप्रवृत्तावुत्सर्गस्यावश्यं प्रवर्तनात् ॥ **गोष्पदप्रमिति** । वर्षप्रमाण ऊलोपश्चास्यान्यतरस्यामित्यूलोपणमुलौ सह विधीयेते ततो लित्स्वराभावात् प्रत्ययाद्युदात्तत्वे सति कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तं पदं भवति ॥ ३३ ॥

(उद्योतः) येन नाप्राप्तिन्यायेनाशनुदात्तत्वस्य लित्स्वरापवादत्वान्नित्यत्वोक्तिरसङ्गतेत्यत आह—एतच्चेति ॥ भाष्ये—उदात्तभावी नास्तीति । अनुदात्तविधानसामर्थ्यादिति भावः ॥ अपवादविषयपरिहारेणोत्सर्गप्रवृत्तेः कथं प्रत्ययस्वरोऽत आह—अपवादाप्रवृत्ताविति ॥ णमुलूलोपाविति । पूरेरिति शेषः ॥ ३३॥

(३५३ आदेशसूत्रम् ॥ २ । ४ । १ आ. १८)

५६५ द्वितीयाटौस्स्वेनः ॥ २।४।३४ ॥

(इदमोपि स्थानित्वाधिकरणम्)

(आक्षेपभाष्यम्)

कस्यायमेनो विधीयते । एतदः प्राप्नोति । इदमोपि त्विष्यते । तदिदमो ग्रहणं कर्तव्यम् ॥

(प्रदीपः) **द्वितीया** ॥ ३४ ॥ उभयोरादेशस्येष्टत्वादेतद एवानन्तर्यात्तत्प्रसङ्गात् पृच्छति—**कस्येति** ॥ **न कर्तव्यमित्युत्तरम्** ॥ **इदमोपीति** । इदंशब्दाच्च श्लो इमप्रत्येन बाधितस्यादेशविधानमेव सत्तानुमानं स्यात् ॥

(उद्योतः) द्वितीयाटौ ॥ ३४ ॥ ननु इदमोऽपि त्विष्यत इत्यनेन 'तदुपायः कः' इति प्रश्नस्य प्रतीयमानत्वात्तदुत्तरं वाच्यं न त्विदमो ग्रहणं कर्तव्यं ? न कर्तव्यमिति विप्रतिपत्तिरुचिता । अग्रे विधिनिषेधयोरभावादत आह—न कर्तव्यमित्युत्तरमिति । एवंच नेयं विप्रतिपत्तिः, अपि तु सामान्याकारेण प्रतीयमानं प्रश्नं तदिदमो ग्रहणं कर्तव्यमिति विशेषाकारेण कृत्वा तस्योत्तरमाहेत्यर्थः ॥ इदंशब्दाविति । एतेनेदमस्त्वलोऽभावादेत इत्यत्र तत्सम्बन्धाभाव इत्यपास्तम् ॥ इमप्रत्येन, इदमो ह इति विहितेन । तथा तसिल्विषयेऽपि इदम इशं बाधित्वाऽयमेव स्यात् ॥

(समाधानभाष्यम्)

न कर्तव्यम् । प्रकृतमनुवर्तते ॥ क प्रकृतम् ? । "इदमोऽन्वादेशेऽशनुदात्तस्तृतीयादौ" इति ॥

(आक्षेपभाष्यम्)

यदि तदनुवर्तते, "एतदस्त्रतसोस्त्रतसौ चानुदात्ताविदमश्च" इतीदमोपि प्राप्नोति ॥

(आक्षेपबाधकभाष्यम्)

नैष दोषः । संबन्धमनुवर्तिष्यते । "इदमोऽन्वादेशेऽशनुदात्तस्तृतीयादौ" । "एतदस्त्रतसोस्त्रतसौ

चानुदात्तौ" इदमोऽन्वादेशेऽशनुदात्तस्तृतीयादावश् भवति । ततः "द्वितीयाटौस्स्वेनः" । इदमः एतदश्च । 'तृतीयादौ' इति निवृत्तम् ॥

अथ वा मण्डूकगतयोऽधिकाराः । तद्यथा— मण्डूका उत्प्लुत्योत्प्लुत्य गच्छन्ति तद्वदधिकाराः ॥

(प्रदीपः) मण्डूकगतय इति । इह केवलस्यादेशस्योपादानादवश्याक्षेप्यः स्थानी । न तु पूर्वत्र, साक्षात् स्थानिनो निर्देशादिति भावः ॥

(आक्षेपबाधकशेषभाष्यम्)

अथ वा एकयोगः करिष्यते—"इदमोऽन्वादेशेऽशनुदात्तस्तृतीयादावेतदस्त्रतसोस्त्रतसौ चानुदात्तौ" । ततः "द्वितीयाटौस्स्वेनः" इदम एतदश्च । तृतीयादाविति निवृत्तम् ॥

(प्रदीपः) अथवैकयोग इति । एकं ग्रहणकवाक्यमित्यर्थः ॥

(उद्योतः) एकं ग्रहणकेति । इदमस्तृतीयादौ एतदस्त्रतसोश्चाशनुदात्तो भवतीत्येवंरूपमित्यर्थः ॥

(आक्षेपबाधकशेषभाष्यम्)

अथवोभयं निवृत्तं तदपेक्षिष्यामहे ॥

(प्रदीपः) तदपेक्षिष्यामह इति । लौकिकोधिकारोऽपेक्षालक्षण आश्रीयते न तु शास्त्रीयः । अपेक्षा च लक्ष्यवशात्समुदायविषयैवेति भावः ॥

(१५९६ वार्तिकम् ॥ १ ॥)

॥ * ॥ एनदिति नपुंसकैकवचने ॥ * ॥

(भाष्यम्) एनदिति नपुंसकैकवचने वक्तव्यम् । इदं कुण्डमानय प्रक्षालयैनत् परिवर्तयैनत् ॥

(प्रदीपः) एनदिति । यद्येनादेशः क्रियते तदाऽत्तोऽमित्यम्भावे सत्येनमिति प्राप्नोति एनदिति चेष्यते इति वार्तिकारम्भः ॥

(आक्षेपभाष्यम्)

यद्येनत्क्रियते एनो न वक्तव्यः ॥

(प्रत्याक्षेपभाष्यम्)

का रूपसिद्धिः—अथो एनम्, अथो एने, अथो एनानीति ? ॥

(प्रत्याक्षेपसमाधानभाष्यम्)

त्यदाद्यत्वेन सिद्धम् ॥

(उद्योतः) एनो न वक्तव्य इति । भाष्ये ॥ तथा च सूत्र एवैनद्वक्तव्यः तकारोच्चारणसामर्थ्याच्च नपुंसके लुग्विषयेऽपि भविष्यति । तकारोच्चारणसामर्थ्यात्त्यदाद्यत्वबाधापेक्षया क्लृप्तबाधस्य मलुमतेति निषेधस्य बाध एवोचित इति भावः ॥ नचैनदस्त्यदाद्यत्वापवादत्वात्तत्र कृते त्यदाद्यत्वं दुर्लभम्, द्वितीयेत्यादिसप्तम्या आर्धधातुक इति साहचर्येण विषयसप्तमीत्वेनापवादस्वस्यैवाभावात् ॥ वस्तुतो यद्येनदित्यादिः पूर्वपक्ष्युक्तिरिति विषयसप्तम्यां मानाभावेनैनादेशः कार्य एवेति बोध्यम् ॥

(समाधानबाधकभाष्यम्)

यद्येवमेनश्रितको न सिध्यति । एनच्छ्रितक इति प्राप्नोति ॥

(प्रदीपः) एनच्छ्रितक इति प्राप्नोतीति । अन्तरङ्गानपि विधीन् बहिरङ्गो लुग् बाधत इति त्यदाद्यत्वमकृत्वा लुक् क्रियते । लुकि च कृते प्रत्ययलक्षणनिषेधात्त्यदाद्यत्वाभाव इति भावः ॥

(समाधानसाधकभाष्यम्)

यथालक्षणमप्रयुक्ते ॥ द्वितीयाटौ ॥ ३४ ॥

(प्रदीपः) यथालक्षणमिति । यस्य प्रयोगो नोपलभ्यते तल्लक्षणानुसारेण संस्कर्तव्यम् । तत्र यदा न लुमताङ्गस्येत्यत्राङ्गाधिकारो निर्दिश्यते तदा प्रत्ययलक्षणेनैनच्छ्रितक इति भाव्यम् । अथानङ्गाधिकारविहितमपि अङ्गकार्यं निषिध्यते तदादेशाभावादेतच्छ्रितक इति भाव्यमित्याहुः ॥ ३४ ॥

(उद्योतः) इत्याहुरिति । अत्रारुचिबीजं तु नपुंसकलुकीवात्रापि लुकि सामर्थ्यादेनदादेशप्रवृत्तिरङ्गाधिकारानिर्देशेऽपि भविष्यतीति भाष्याशयः । बहिरङ्गत्वं तु न लुग्विषये दुर्बलतानियामकमिति दिक् । वस्तुतोऽप्रयुक्तत्वाल्लक्षणस्यायमविषय इति भाष्यार्थ इति बोध्यम् ॥ ३४ ॥

(अन्वादेशप्रकरणं समाप्तम्)

(अथार्धधातुकाधिकारप्रकरणम्)

(३५४ अधिकारसूत्रम् ॥ २ । ४ । १ आ. १९)

५६६ आर्धधातुके ॥ २।४।३५ ॥

(सप्तम्या वैषयिकत्वाधिकरणम्)

(१५९७ आक्षेपवार्तिकप्रथमखण्डम् ॥ १ ॥)

॥ * ॥ जग्ध्यादिष्वार्धधातुकाश्रयत्वात्सति तस्मिन्विधानम् ॥ * ॥

(भाष्यम्) जग्ध्यादिष्वार्धधातुकाश्रयत्वात्सति तस्मिन्नार्धधातुके जग्ध्यादिभिर्भवितव्यम् ॥

(आक्षेपभाष्यम्)

किमतो यत्सति भवितव्यम् ? ।

(१५९८ आक्षेपवार्तिकद्वितीयखण्डम् ॥ २ ॥)

॥ * ॥ तत्रोत्सर्गलक्षणप्रतिषेधः ॥ * ॥

(भाष्यम्) तत्रोत्सर्गलक्षणं कार्यं प्राप्नोति तस्य प्रतिषेधो वक्तव्यः । भव्यं प्रवेयम् आख्येयम् । ण्यत्यवस्थितेऽनिष्टे प्रत्यय आदेशः स्यात् । ण्यतः श्रवणं प्रसज्येत ॥

(प्रदीपः) आर्ध ॥ ३५ ॥ जग्ध्यादिष्विति । व्यक्तौ पदार्थे परसप्तम्यां सत्यां परस्मिन् व्यवस्थिते आर्धधातुके आदेशेन भाव्यम् । तत्र विशिष्टार्धधातुकाश्रयेषु जग्ध्यादिषु यद्यपि दोषाभावस्तथापि भूवीत्यादौ तु दोषः ॥ तत्रेति । उत्सर्गशब्देन स्थानी विवक्षित आदेशेनापवादेन बाध्यमानत्वात् ॥

(उद्द्योतः) आर्धधा ॥ ३५ ॥ व्यक्ताविति । परसप्तम्या उचिततया तत्पक्षस्यैवाश्रयणमुचितमिति भावः ॥ तथापि भूवीति । अत एव जग्ध्यादिष्वित्युक्त्वाऽपि भव्यमित्याद्येव भाष्ये उदाहृतम् । वचेरप्युपलक्षणमेतत् ॥ ण्यतो यदुत्सर्गत्वाभावादाह—उत्सर्गशब्देनेति ॥ भाष्ये—ण्यतः श्रवणमिति । ण्यत्कार्यस्य वृद्ध्यादेरित्यर्थः ॥

(१५९९ समाधानवार्तिकम् ॥ ३ ॥)

॥ * ॥ सामान्याश्रयत्वाद्विशेषस्यानाश्रयः ॥ * ॥

(भाष्यम्) सामान्ये ह्याश्रीयमाणे विशेषो नाश्रितो भवति तत्रार्धधातुकसामान्ये जग्ध्यादिषु यो यतः प्रत्ययः प्राप्नोति स ततो भविष्यति ॥

(प्रदीपः) सामान्याश्रयत्वादिति । आकृतिपदार्थाश्रयेणोत्तरम् ॥

(उद्द्योतः) आकृतीति । एवं चार्धधातुकत्वजातिविषये आदेशा नतु प्रत्यये परे इति भ्वाद्यादेशेषु कृतेषु पश्चाद्यदेव भविष्यतीति भावः ॥

(१६०० आक्षेपवार्तिकम् ॥ ४ ॥)

॥ * ॥ सामान्याश्रयत्वाद्विशेषस्यानाश्रय इति चेदुवर्णाकारान्तेभ्यो ण्यद्विधिप्रसङ्गः ॥ * ॥

(भाष्यम्) सामान्याश्रयत्वाद्विशेषस्यानाश्रय इति चेद् उवर्णाकारान्तेभ्यो ण्यत्प्राप्नोति । लव्यं पव्यमिति आर्धधातुकसामान्ये गुणे कृते यि प्रत्ययसामान्ये च वान्तादेशे "हलन्ताद्" इति ण्यत्प्राप्नोति । इह च दित्स्यं धित्स्यम् आर्धधातुकसामान्ये अकारलोपे कृते "हलन्ताद्" इति ण्यत्प्राप्नोति ॥

(प्रदीपः) जातिपक्षस्य दोषवत्तां प्रतिपादयितुमाह—उवर्णाकारान्तेभ्य इति ॥

(उद्द्योतः) जातिपक्षस्येति । सर्वेषां निमित्तवाचकशब्दानां जातिपरत्वं स्यादित्यभिप्रायेण दोषदानमिति भावः ॥ दित्स्यधित्स्ययोर्यति यतो नाव इत्याद्युदात्तत्वम्, ण्यति 'तित्स्वरित'मिति स्वरितत्वमिति भेदः ॥

(१६०१ आक्षेपान्तरवार्तिकम् ॥ ५ ॥)

॥ * ॥ पौर्वापर्याभावाच्च सामान्येनानुपपत्तिः ॥ * ॥

(भाष्यम्) पौर्वापर्याभावाच्च सामान्येन जग्ध्यादीनामनुपपत्तिः । न हि सामान्येन पौर्वापर्यमस्ति ॥

(प्रदीपः) इदानीमाकृतिपक्षाश्रयस्यासंभवमाह—पौर्वापर्याभावाच्चेति । सामान्यस्य व्यापकत्वान्नित्यत्वाच्च देशकालकृतं पौर्वापर्यं नास्ति । सप्तम्या चेह परत्वं प्रतिपादितम् । तस्माद्व्यक्तिपक्षः परत्वोपपत्तय आश्रयणीयः । तत्र च भव्याद्यसिद्धिः ॥

(उद्द्योतः) व्यापकत्वादिति । सर्वदेशस्याश्रयाश्रितत्वादिति भावः । तत्र व्यापकत्वाद्देशकृतं नित्यत्वात्कालकृतमिति विभागः ॥ सप्तम्या चेहेति । तस्मिन्निति शास्त्रबलादत्र शास्त्रे विषयसप्तम्यभावं मन्यते ॥

(१६०२ न्यासान्तरेणसमाधानवार्तिकम् ॥ ६ ॥)

॥ * ॥ सिद्धं तु सार्वधातुके प्रतिषेधात् ॥ * ॥

(भाष्यम्) सिद्धमेतत् । कथम् ? । अविशेषेण जग्ध्यादीनुक्त्वा "सार्वधातुके न" इति प्रतिषेधं वक्ष्यामि ॥

(आक्षेपभाष्यम्)

सिध्यति । सूत्रं तर्हि भिद्यते ॥

(सिद्धान्तिभाष्यम्)

यथान्यासमेवास्तु ॥

(आक्षेपकारणभाष्यम्)

ननु चोक्तम् *जग्ध्यादिष्वार्धधातुकाश्रयत्वात्सति तस्मिन्विधानम्* इति ॥

(समाधानकारणभाष्यम्)

परिहृतमेतत् *सामान्याश्रयत्वाद्विशेषस्यानाश्रय* इति ॥

(आक्षेपकारणभाष्यम्)

ननु चोक्तम् *सामान्याश्रयत्वाद्विशेषस्यानाश्रय इति चेदुवर्णाकारान्तेभ्यो ण्यद्विधिप्रसङ्ग* इति ॥

(समाधानभाष्यम्)

नैष दोषः । वक्ष्यति तत्राज्ग्रहणस्य प्रयोजनम्—'अजन्तभूतपूर्वमात्रादपि यथा स्याद्' इति ॥

(प्रदीपः) वक्ष्यति तत्रेति । हलन्ताद् ण्यतो विधानादज्ग्रहणमन्तरेणाप्यजन्तादेव यति सिद्धेऽज्ग्रहणं भूतपूर्वस्याप्यजन्तस्य परिग्रहार्थमित्यर्थः ॥

(उद्द्योतः) भूतपूर्वस्येति । अङ्गस्वस्य विधानप्रतिबद्धतया-ज्ञाधिकारे सामान्याश्रयत्वस्य वक्तुमशक्यतया ण्यल्लोपावियङ्यण्गुणेत्यादिपूर्वविप्रतिषेधवार्त्तिकभाष्येण अतोलोपादीनां स्थानिवत्त्वपरभाष्यविरोधेन चास्य भाष्यस्य प्रौढिवादपरत्वमिति केचित् । वस्तुतो विषयसप्तम्यामपि परनिमित्तत्वं वक्तुं शक्यमिति न दोषः । अङ्गसंज्ञासूत्रेऽपि यस्मात् यस्य प्रत्ययस्य विधानं तस्मिन्विवक्षित एवाङ्गत्वविधानेऽपि न दोष इति भाष्याशयः ॥

(द्वितीयाक्षेपपरिहारबाधकभाष्यम्)

यदप्युच्यते—*पौर्वापर्याभावाच्च सामान्येनानुपपत्तिः* इति ॥ अर्थसिद्धिरेवैषा यत्सामान्येन पौर्वापर्यं नास्तीति । असति पौर्वापर्ये विषयसप्तमी विज्ञास्यते 'आर्धधातुके विषये' इति । तत्रार्धधातुके विषये जग्ध्यादिषु कृतेषु यो यतः प्राप्नोति स ततो भविष्यति ॥

अथ वा आर्धधातुकास्विति वक्ष्यामि । कासु आर्धधातुकासु?। उक्तिषु युक्तिषु रूढिषु प्रतीतिषु श्रुतिषु संज्ञासु ॥ आर्धधातुके ॥ ३५ ॥

(प्रदीपः) अर्थसिद्धिरिति । एषैव प्रयोजनसंपत्तिरित्यर्थः ॥ विषये इति । बुद्धिस्थ इत्यर्थः । अभिव्यङ्क्ष्यते तत्रार्धधातुकत्वमित्येवं बुद्ध्या निरूपित इति भावः ॥ अथ वेति । व्यक्तिपक्षाश्रयणेपि न दोष इत्युक्तं भवति । नित्यानां भव्यादीनां शब्दानामनेन साधुत्वमात्रं प्रतिपाद्यते । तत्रार्धधातुकं विद्यते यासु ता भव्यादय आर्धधातुकावयवाः शब्दसंहतय आर्धधातुकशब्देनार्शआदित्वादच्प्रत्ययान्तेनोच्यन्ते ॥ उक्तिष्विति । उच्यन्ते उच्चार्यन्त इत्युक्तयस्ता एव शब्दसंहतयः । अन्ये तु उच समवाय इत्यस्य क्तिन्युक्तिशब्दः संहतिपर्याय इत्याहुः । समवायो हि संहतिः ॥ युक्तिष्विति । अर्थेन संबद्धास्वित्यर्थः ॥ रूढिष्विति । परमार्थतो नित्यास्वित्यर्थः ॥ प्रतीतिष्विति । अनेन नित्यत्वेपि व्यवहारानित्यत्वं प्रतिपाद्यते । तदेव दर्शयति—श्रुतिष्विति । एवंभूतानामेव व्यवहारे श्रूयमाणत्वादित्यर्थः ॥ संज्ञास्विति । बालव्युत्पत्तये प्रकृत्यादिविभागेन संज्ञायमानास्वित्यर्थः । ततश्च यस्य च भावेनेति सप्तमी । आर्धधातुकासु संहतिषु व्युत्पाद्यमानासु अस्त्यादीनां भ्वादय आदेशा इत्युक्तं भवति ॥ ३५ ॥

(उद्द्योतः) भाष्ये—असति पौर्वापर्ये इति । न च व्यक्तिद्वारकं पौर्वापर्यम् । अतएव हलन्ताच्चेति सूत्रे व्यक्तिद्वारकं सामीप्यं कैयटेनोक्तम् । अतः कथमिदं भाष्यमिति वाच्यम् ॥ तस्य कैयटस्य तत्रैव सूत्रेऽप्रयोजकत्वस्य मया बोधितत्वात् । परम्परासम्बन्धस्यासम्बन्धताया अनेकमन्यपदार्थे इति सूत्रे भाष्ये उक्तेः ॥ आर्धधातुकावयवा इति । अत एवैषां यङ्लुगन्ते प्रयोगा नेत्याहुः । लुकि आर्धधातुकावयवत्वाभावात् ॥ प्रतीतिष्विति । प्रयुज्यमानास्वित्यर्थः । न केवलेति संकेतात् प्रकृतिप्रत्ययसमुदाय एव प्रयुज्यते । एवं च तस्य व्यावहारिकत्वादनित्यत्वं संपन्नमित्याह—व्यवहारेति ॥ ३५ ॥

(३५५ आदेशसूत्रम् ॥ २ । ४ । १ आ. २० सू.)

५६७ अदो जग्धिर्ल्यप्ति किति २।४।३६ ॥

(अन्तरङ्गानपि विधीन् बहिरङ्गो ल्यब् बाधत इति परिभाषाधिकरणम्)

(आक्षेपभाष्यम्)

ल्यब्ग्रहणं किमर्थम् । न 'ति किती'त्येव सिद्धम्॥

(आक्षेपबाधकभाष्यम्)

ल्यपि कृते न प्राप्नोति ॥

(आक्षेपसाधकभाष्यम्)

इदमिह संप्रधार्यम्—ल्यप् क्रियताम्, आदेश इति, किमत्र कर्तव्यम्?। परत्वाल्ल्यप् । अन्तरङ्ग आदेशः ॥

(प्रदीपः) अदो जग्धि ॥ ३६ ॥ अन्तरङ्ग आदेश इति । तकारादिप्रत्ययमात्रापेक्षत्वात् । ल्यबादेशस्तु पूर्वपदापेक्षसमासाश्रयत्वाद् बहिरङ्गः ॥

(उद्द्योतः) अदोजग्धि ॥ ३६ ॥ तकारादिप्रत्ययमात्रेति । सूत्रे विषयसप्तमीति युक्तं वक्तुम् ॥

(समाधानभाष्यम्)

एवं तर्हि सिद्धे सति यल्ल्यब्ग्रहणं करोति तज्ज्ञापयत्याचार्यः—'अन्तरङ्गानपि विधीन्बहिरङ्गो ल्यब् बाधते' इति । किमेतस्य ज्ञापने प्रयोजनम्?। *ल्यबादेश उपदेशिवद्वचनमनादिष्टार्थं बहिरङ्गलक्षणत्वाद्* इति वक्ष्यति, तन्न वक्तव्यं भवति ॥

(प्रदीपः) अनादिष्टार्थमिति । प्रधाय प्रस्थायेत्यादौ हित्वादिष्वकृतेष्वेव ल्यब् यथा स्यादित्यर्थः । कथं न प्राप्नोतीत्याह—बहिरङ्गलक्षणत्वादिति ॥

(उद्द्योतः) भाष्ये—उपदेशिवद्वचनमिति । उपदेशी क्त्व तद्वत् ल्यपो वचनं कार्यमित्यर्थः । भाविन्येव समासे क्त्वो ल्यबादेश इति भावः । अनादिष्टार्थं हित्वाद्यादेशाभावार्थमित्यर्थः ॥ प्रधाये-

त्यादि । हित्वेत्यादिष्वनादिष्टेषु अकृतेषु यथा स्यादित्येषो अनादिष्टार्थमित्यस्यार्थ इति भावः ॥ हित्वादिष्विति । आदिना हित्वदत्त्वेत्वदीर्घत्वानि गृह्यन्ते ॥

(संवादभाष्यम्)

जग्धिविधिर्ल्यपि यसदकस्मा-
त्सिद्धमदस्ति कितीति विधानात् ॥
हिप्रभृतींस्तु सदा बहिरङ्गो
ल्यब्भरतीति कृतं तदु विद्धि ॥ १ ॥

(प्रदीपः) अयमेवार्थो व्याघ्रभूतिनाप्युक्त इत्याह— **जग्धिविधिरिति** ॥ **अकस्मादिति** । निष्प्रयोजनमित्यर्थः ॥ **सिद्धमद इति** । जग्धिविधानं सिद्धमित्यर्थः ॥ ज्ञापनार्थं ल्यपि जग्धिविधानमित्याह—**हिप्रभृतीनिति** ॥ **ल्यब्भरतीति** । ल्यबादेशो दूरत्यपनयति बाधत इत्यर्थः ॥ **तदु इति** । उशब्दो निपातोऽवधारणार्थः । तद्विध्येवेत्यर्थः ॥ ३६ ॥

(उद्द्योतः) वार्तिके य(त्त)दिति सामान्ये नपुंसकम् । जग्धिरिति यः स इत्यर्थः ॥ **अकस्मात्** । न कस्माचित्प्रयोजनादित्यर्थः । अनर्थक इति भावः । कुतस्तत्राह—**सिद्धमिति** । **अद इति** । सामान्ये नपुंसकम् । यतोऽत इति च शेषः ॥

(संवादभाष्यम्)

एष एवार्थः—

"जग्धौ सिद्धेऽन्तरङ्गत्वात्ति कितीति ल्यबुच्यते ॥

ज्ञापयत्यन्तरङ्गाणां ल्यपा भवति बाधनम्" इति ॥ अदोजग्धि ॥ ३६ ॥

(उद्द्योतः) एष एवार्थ इति । अन्येन निबद्ध इति शेषः । मया निबध्यत इति वा ॥ ३६ ॥

(३५६ आदेशसूत्रम् ॥ २ । ४ । १ आ. २१ ॥)

५६८ लुङ्सनोर्घस्लृ ॥ २।४।३७ ॥

(१६०३ शेषवार्तिकम् ॥१॥)

॥ * ॥ घस्लृभावेऽच्युपसंख्यानम् ॥ * ॥

(भाष्यम्) घस्लृभावेऽच्युपसंख्यानं कर्तव्यम् । प्रात्तीति प्रघसः ॥ लुङ्सनो ॥ ३७ ॥

(३५७ आदेशसूत्रम् ॥ २ । ४ । १ आ. २२)

५७३ हनो वध लिङि ॥ २।४।४२ ॥

(३५८ आदेशसूत्रम् ॥ २ ।४। १ आ. २३)

५७४ लुङि च ॥ २।४।४३ ॥

(आदेशोऽदन्तत्वनिर्णयाधिकरणम्)

(आक्षेपभाष्यम्)

किमयमदन्तः, आहोस्विद्व्यञ्जनान्तः ? ॥

(प्रदीपः) **हनो वध** ॥ ४२ ॥ **किमयमिति** । किं कार्यार्थोऽकारोऽथोच्चारणार्थ इति प्रश्नः ॥

(भाष्यम्) **किं चातः ?** ॥

(विशेषप्रदर्शकभाष्यम्)

यदि व्यञ्जनान्तः *वधौ व्यञ्जनान्त उक्तम्* । किमुक्तम् ? । *वध्यादेशे वृद्धितत्वप्रतिषेध इड्विधिश्च* इति । अथादन्तः । न दोषो भवति ॥

(प्रदीपः) **वृद्धितत्त्वप्रतिषेध इति** । अवधीदित्यत्रातो **हलादेर्लघोरिति** हलन्तलक्षणा वृद्धिः प्राप्नोति, वधक इति ण्वुलि वधादेशे औपसंख्यानिके कृते **अत उपधाया** इति वृद्धिः प्राप्नोति, सा **जनिवध्योश्चेति** प्रतिषिध्यते । स्थानिवद्भावात्तु तत्वं प्राप्तम् ॥ **इड्विधिश्चेति** । अवधीदित्यादावेकाच्त्वादिट्प्रतिषेधः प्राप्नोतीतीड्विधेयः ॥ अदन्तत्वे त्वल्लोपस्य स्थानिवत्त्वाद्वृद्धितत्वादेरभावः । तत्वं **त्वलोन्त्यस्य** क्रियते । तत्राकारो लुप्तत्वात् स्थानी न भवति धकारोपि अल्लोपस्य स्थानिवत्त्वादन्त्यो न भवतीति तत्त्वाभावः । उपदेशेनेकाच्त्वाच्च प्रतिषेधाभावादिट्सिद्धिः ॥ ४२ ॥ ४३ ॥

(उद्द्योतः) **हनोवध** ॥ ४२ ॥ ४३॥ **हलन्तलक्षणेति** । हलन्तलक्षणायाः प्रतिप्रसवभूतेत्यर्थः ॥ **औपसंख्यानिके इति** । बहुलं तणीत्यनेनेति भावः । **स्थानिवद्भावादिति** । **स्थानिवदादेश** इत्यनेन ॥ **अल्लोपस्येति** । **अचः परस्मिन्नित्य**नेन । एवञ्च जनिवध्योश्चेति सूत्रे वधिग्रहणं न कार्यमिति भावः । स्वतश्चो वधधातुस्तु नास्त्येव । अत एव व्यञ्जनान्तेऽवधीदित्यादौ वृद्धिप्रतिषेधो वक्तव्य इति संगच्छते । अन्यथा तस्य वृद्धेर्दुर्वारत्वेन तदसङ्गतिः ॥ **लुप्तत्वात्तस्थानी न भवतीति** । अतिदेशोनाद्यार्थबुद्धिसत्वेऽपि षष्ठ्यर्थस्योच्चारणरूपप्रसङ्गस्य वक्तुमशक्यत्वात् ॥ **उपदेश इति** । वध्युपदेशे इत्यर्थः । उपदेशत्वावच्छेदेनैकाच्त्वस्य विवक्षणादिति भावः ॥ ४२ ॥ ४३ ॥

(सिद्धान्तिभाष्यम्)

यथा न दोषस्तथास्तु ॥ हनो ॥ ४२ ॥ ४३ ॥

(३५९ आदेशसूत्रम् २।४। १ आ. २४)

५७६ इणो गा लुङि ॥ २।४।४५ ॥

(१६०४ अतिदेशवार्तिकम् ॥ १ ॥)

॥ * ॥ इण्वदिकः ॥ * ॥

(भाष्यम्) इण्वदिक इति वक्तव्यम् । इहापि यथा स्यात्—अध्यगात् । अध्यगाताम् । अध्यगुः॥ इणो गा ॥ ४५ ॥

(३६० आदेशसूत्रम् ॥ २।४।१ आ. २५ सू.)

५७७ णौ गमिरबोधने ॥ २।४।४६ ॥

(भाष्यम्) इण्वदिक इत्येव । अधिगमयति । अधिगमयतः । अधिगमयन्ति ॥ णौ गमि ॥ ४६ ॥

(३६१ आदेशसूत्रम् ॥ २ । ४ । १ आ. २६)

५७८ सनि च ॥ २।४।४७ ॥

(भाष्यम्) इण्वदिक इत्येव । अधिजिगमिषति । अधिजिगमिषतः । अधिजिगमिषन्ति ॥ सनि च ॥ ४७ ॥

(३६२ आदेशसूत्रम् ॥ २ । ४ । १ आ. २७)

५८० गाङ् लिटि ॥ २।४।४९ ॥

(ङित्करणप्रयोजनाधिकरणम्)

(आक्षेपभाष्यम्)

ङित्करणं किमर्थम् ? ॥

(प्रदीपः) गाङ् लिटि ॥ ४९ ॥ स्थानिवद्भावात्सिद्धमात्मनेपदं मत्वाह—ङित्करणमिति ॥

(१६०५ सिद्धान्तिसमाधानवार्तिकम् ॥१॥)

॥ * ॥ गाङ्यनुबन्धकरणं विशेषणार्थम् ॥ * ॥

(भाष्यम्) गाङ्यनुबन्धकरणं क्रियते । विशेषणार्थम् ॥ क्व विशेषणार्थेनार्थः ? । "गाङ्कुटादिभ्योऽञ्णिन्ङिद्" इति । 'गाकुटादिभ्यः' इति ह्युच्यमाने इणादेशस्यापि प्रसज्येत ॥

(प्रदीपः) इणादेशस्यापीति । ततश्चागासातां ग्रामौ देवदत्तेनेत्यादौ ङित्त्वादीत्वप्रसङ्गः ॥ गाङ्कुटादिभ्य इति तूच्यमानेस्यैव ग्रहणं भवति, न तु गाङ् गताविस्यस्य एतदङ्कारस्यात्मनेपदविधौ चरितार्थत्वादादेशेनानन्यार्थङकारेण तुल्यताभावात् ॥

(उद्योतः) गाङ् लिटि ॥ ४९ ॥ ङित्वादीत्वेति । घुमास्थेत्यनेनेति भावः ॥ इणः परस्मैपदित्वेन लुङि गातिस्थेति सिचो लोपादातिदेशिकङित्वभाजोऽभावात्कर्मणि चिण्वदिडभावपक्षे उदाहृतम् ॥ न तु गाङ् गताविति । तस्यापि ग्रहणे तु सामान्यग्रहणार्थमिति वदेत् । नतु विशेषणार्थमितीति भावः ॥ तुल्यताभावादिति । वस्तुतो भाष्यप्रामाण्येन व्याख्यानादेवास्याग्रहणम् । अतएव घटायोन्मीलितमिति न्यायविरोधो न ॥

(१६०६ एकदेशिसमाधानान्तरवार्तिकम् ॥२॥)

॥ * ॥ ज्ञापकं वा सानुबन्धकस्यादेशवचन इत्कार्याभावस्य ॥ * ॥

(भाष्यम्) अथ वैतज्ज्ञापयत्याचार्यः—सानुबन्धकस्यादेश इत्कार्यं न भवतीति ॥

(प्रदीपः) ज्ञापकं वेति । सानुबन्धायत्र षष्ठ्युच्चार्यते तत्राकृतायामेवेत्संज्ञायामादेशः प्रवर्तते । कृतायां वेत्संज्ञायां तन्निबन्धनानि कार्याणि न प्रवर्तन्त इति ज्ञापनार्थं ङकारोच्चारणमित्यर्थः ॥

(उद्योतः) सानुबन्धादिति । गाङ्कुटादिभ्य इत्यत्र व्याख्यानादिङादेशस्यैव ग्रहणं भविष्यतीत्याशयेन ज्ञापकोपन्यासः॥ कृतायाञ्चेति । अनल्विधाविति प्रतिषेधस्तु स्थान्यलाश्रये कार्ये । अनुबन्धश्च लुप्तत्वात्स्थानिनि न संनिधीयत इत्यर्थः ॥

(भाष्यम्) किमेतस्य ज्ञापने प्रयोजनम् ? ॥

(१६०७ प्रयोजनवार्तिकम् ॥३॥)

॥ * ॥ प्रयोजनं चक्षिङः ख्याञ् ॥ * ॥

(भाष्यम्) (चक्षिङः ख्याञ्प्रयोजनम्—चख्यौ ख्यास्यति) इति 'ङित' इत्यात्मनेपदं नित्यं न भवति ॥

(१६०८ प्रयोजनवार्तिकम् ॥४॥)

॥ * ॥ लटः शतृशानचौ ॥ * ॥

(भाष्यम्) (लटः शतृशानचौ) प्रयोजनम् पचमानो यजमान इति 'टित' इत्येत्वं न भवति ॥

(प्रदीपः) शतृशानचाविति । सूत्रे सहनिर्दिष्टत्वादत्रापि सहोपादानम् । शानजेव त्वात्मनेपदत्वात् प्रयोजनम् ॥

(१६०९ प्रयोजनवार्तिकम् ॥५॥)

॥ * ॥ युवोरनाकौ ॥ * ॥

(भाष्यम्) युवोरनाकौ च प्रयोजनम् । नन्दनः कारकः नन्दना कारिकेति। उगिल्लक्षणौ ङीब्नुमौ न भवतः ॥

(प्रदीपः) युवोरनाकाविति। भुज्युशंयूर्णायुप्रभृतिष्वादेशनिवारणायानुनासिकोकारानुबन्धौ युवू सूत्रे निर्दिष्टौ। तत्रादेशप्रवृत्तावेतस्माज्ज्ञापकादुगित्कार्याप्रवृत्तिरिति ङीम्नुमोरभावः॥

(उद्द्योतः) भाष्ये—नन्दनेति। 'ल्युः कर्त्तरि पुंसि' इत्यमरस्य प्रमादः' इति वा॥

(१६१० दूषणवार्तिकम्॥६॥)

॥ * ॥ मेश्चानानुबन्धकस्याम्वचनम् ॥ * ॥

(भाष्यम्) मेश्चानानुबन्धकस्याम्वक्तव्यः। अचिनवम्। असुनवम्। अकरवम्॥

(प्रदीपः) ज्ञापकस्यातिव्याप्तिं दृष्ट्वाह—मेश्चेति। तस्थस्थमिपामित्यत्र मिव्ग्रहणमपनीय मिग्रहणं कर्तव्यमित्यर्थः। तेन सानुबन्धः स्थानी न भवतीति पित्कार्यं प्रवर्तते॥ अचिनवमिति। पित्त्वात् ङित्त्वाभावाद् गुणो भवति। मा हि स्म चिनवमिति चानुदात्तत्वम्॥

(उद्द्योतः) अनुदात्तत्वमिति। पित्त्वादित्यर्थः। अट्निषेधाय माङ्, लङर्थः स्मः, निघातप्रतिषेधाय हिः॥

(वार्तिकपूर्तिभाष्यम्)

अत्यल्पमिदमुच्यते-मेरिति। तिप्सिम्मिपामिति वक्तव्यम्। इहापि यथा स्यात्—वेद वेत्थ॥

(प्रदीपः) वार्तिककारस्याव्याप्तिमुद्भावयन्नाह—अत्यल्पमिति। णलादिविधौ तु तिप्सिपोः सानुबन्धकयोरनुपादानान्नास्ति दोष इति चिन्त्यमेतत्॥

(उद्द्योतः) चिन्त्यमेतदिति। वस्तुतस्तु परस्मैपदानां णलतुर्विदो लटो वेत्यादौ यथासंख्यनिर्वाहाय परस्मैपदानां क्रमेणोपस्थितये तिप्तस्झिसित्यादिसूत्रस्थक्रमेणोपस्थितौ सानुबन्धकयोरेवोपस्थितिरिति भाष्याशयः॥

(ज्ञापितप्रत्याख्यानभाष्यम्)

अस्य ज्ञापकस्य सन्ति दोषाः॥
सन्ति प्रयोजनानि॥
दोषाः समाः भूयांसो वा। तस्मान्नार्थो ज्ञापकेन॥

(प्रदीपः) भूयांसो वेति। दोषबहुत्वारोपेण निन्दामाह॥ तस्मादिति। विशेषणार्थं तु ङित्करणं स्थितम्॥

(उद्द्योतः) निन्दामाहेति। अन्यथा दोषाणामाधिक्याभावात्प्रकर्षप्रयोगोऽनुपपन्न इति भावः॥

(आक्षेपभाष्यम्)

कथं यानि प्रयोजनानि?॥

(समाधानभाष्यम्)

नैतानि सन्ति। इह तावत् "चक्षिङः ख्याञ्" इति। ञित्करणसामर्थ्याद्विभाषात्मनेपदं भविष्यति॥

(प्रदीपः) विभाषात्मनेपदमिति। कर्त्रभिप्राये क्रियाफले आत्मनेपदं नान्यत्रेत्यर्थः॥

(उद्द्योतः) स्वरितञित इत्यत्र विकल्पवाचिनोऽनुपादानादाह—कर्त्रभीति॥

(द्वितीयप्रयोजननिराकरणम्)

"लटः शतृशानचौ" इति। वक्ष्यत्येतत्—"प्रकृतानामात्मनेपदानां टेरेत्वं भवति" इति॥

(प्रदीपः) प्रकृतानामिति। तिप्तस्झीत्यत्र यान्यात्मनेपदान्युपात्तानि तेषामित्यर्थः॥

(तृतीयप्रयोजननिराकरणभाष्यम्)

"युवोरनाकौ" इति। वक्ष्यत्येतत्—*सिद्धं तु युवोरनुनासिकत्वात्* इति॥ गाङ्॥ ४९॥

(प्रदीपः) सिद्धं त्विति। अनुनासिकयोरेवादेशो नान्ययोरित्यर्थः। ततश्च स्थानिनोरेवोगित्त्वं नास्तीति कुतस्तदादेशयोरुगित्कार्यप्रसङ्गः॥ ४९॥

(उद्द्योतः) अनुनासिकयोरिति। युवोरिति विशेष्यम्। उगित्त्वं नास्तीति। उकारविशिष्टस्य स्थानित्वादिति भावः॥४९॥

(३६३ आदेशसूत्रम्॥ २। ४। १ आ. २८)

५८५ चक्षिङः ख्याञ्॥ २।४।५४॥

(आदेशनिर्णयाधिकरणम्)

(आक्षेपभाष्यम्)

किमयं कशादिः, आहोस्वित्ख्यादिः॥

(प्रदीपः) चक्षिङः॥ ५४॥ लक्ष्ये रूपद्वयदर्शनादेकतराश्रयणे इतरासिद्धिप्रसङ्गात् पृच्छति—किमयमिति॥

(उद्द्योतः) चक्षिङः ख्या॥ ५४॥ रूपद्वयेति। चक्शौ चख्याविति इत्यर्थः॥ भाष्ये—ख्यादिरिति। खकारयकारादिरित्यर्थः। एवं कशादिः खशादिरित्यपि ककारशकारादिः खकारशकारादिरित्यर्थकम्॥

(१६११ समाधानवार्तिकम्॥१॥)

॥ * ॥ चक्षिङः कशाञ्ख्याञौ ॥ * ॥

(भाष्यम्) चक्षिङः कशाञ् ख्याञ् इति कशादिः ख्यादिश्च॥

(१६१२ सिद्धान्तिसमाधानवार्तिकम्॥२॥)

॥ * ॥ खशादिर्वा ॥ * ॥

(भाष्यम्) अथ वा खशादिर्भविष्यति॥

(आक्षेपभाष्यम्)

केनेदानीं क्शादिर्भवति ? ॥

(समाधानभाष्यम्)

चर्त्वेन ॥

(आक्षेपभाष्यम्)

(अथ) ख्यादिः कथम् ॥

(१६१३ समाधानवार्तिकम् ॥३॥)

॥*॥ असिद्धे शस्य यवचनं विभाषा ॥*॥

(भाष्यम्) **असिद्धे शस्य विभाषा यत्वं वक्तव्यम् ॥**

(प्रदीपः) **असिद्ध इति । पूर्वत्रासिद्धमित्यधिकारे** णत्वविधानानन्तरं शस्य यत्वं विभाषा वक्तव्यम् । तत्र यत्वस्य पूर्वत्रासिद्धत्वात्तन्निमित्तं कार्यं न प्रवर्तते शकारनिमित्तं च प्रवर्तते । चर्त्वे तु कर्तव्ये यत्वं सिद्धमिति खस्य चर्त्वाभावाद्आख्यातेत्यादि सिध्यति ॥

(आक्षेपभाष्यम्)

किं प्रयोजनम् ? ॥

(१६१४ प्रयोजनवार्तिकम् ॥४॥)

॥ * ॥ प्रयोजनं सौप्रख्ये वुञ्विधिः ॥ * ॥

(भाष्यम्) **सौप्रख्य इति योपधलक्षणो वुञ्विधिर्न भवति ॥ सौप्रख्यीय इति "वृद्धाच्छ" इति छो भवति ॥**

(प्रदीपः) **सौप्रख्येवुञ्विधिरिति ।** अकारप्रश्लेषात्सौप्रख्यशब्दे वुञ्विधिर्न भवतीत्यर्थः । सुप्रचष्ट इति सुप्रख्यः । आतश्चोपसर्गे इति कः । यत्वस्यासिद्धत्वात् सुप्रख्यस्य भाव इति योपधलक्षणवुञभावात् ष्यञ् भवतीति ॥ तथा सुप्रख्येन निर्वृत्तो देशः सौप्रख्यस्तत्र भवः सौप्रख्यीय इति धन्वयोपधाद्वुञिति वुञभावे वृद्धाच्छो भवति ॥

(उद्द्योतः) अकारप्रश्लेषादिति । वस्तुतस्तु तं विनापि मशका धूमप्रयोजनमित्यादेरिव वुञ्विधिर्निवर्त्यत्वेन प्रयोजनमिति वार्त्तिकार्थः । अग्रिमवार्त्तिकाणामेवमेव व्याख्येयत्वात् ॥ अस्य वार्त्तिकस्य भाष्ये अनुक्तमप्यर्थं योग्यतया संभाव्याह—ष्यञ् भवतीति । योपधाद्गुरूपोत्तमाद्वुञिति प्राप्तवुञोऽभावे ब्राह्मणादित्वात्ष्यञिति भावः ॥

(१६१५ प्रयोजनवार्तिकम् ॥५॥)

॥ * ॥ निष्ठानत्वमाख्याते ॥ * ॥

(भाष्यम्) **आख्यात इति निष्ठानत्वं न भवति ॥**

(प्रदीपः) **निष्ठानत्वमिति । न ध्याख्येति तु प्रति**षेधः ख्या प्रकथन इत्यस्यैव प्रतिपदोक्तत्वात् । अस्य तु शस्य यत्वेन लाक्षणिकत्वादिति मन्यते ॥

(उद्द्योतः) लाक्षणिकत्वादिति । अस्य तत्रामहणे आख्यानमित्यपि स्यादिति तद्व्यावृत्त्यर्थं खशादित्वमिति भावः ॥ वस्तुतः स्वतन्त्रख्याधातोरार्धधातुके प्रयोगाभाव एवेष्टव्यः । अन्यथा तमादाय सौप्रख्यादौ वुञादि दुर्वारमेव स्यादित्यस्य खशादित्ववैयर्थ्यापत्तेः । न च पाक्षिकष्यञादिसिद्धिरेव फलम् सस्थानत्वं नमः ख्यात्रे इति भाष्यस्य सर्वथा असंगतेः । जिह्वामूलीयस्य वैकल्पिकत्वेन विसर्गसिद्धेर्जिह्वामूलीयस्य दुर्वारत्वाच्च । एवं च न ध्याख्येत्यत्र तद्ग्रहणे फलाभावात्तदपि न कर्त्तव्यमेवेति भाष्याशयः ॥ ख्याधातुरपि खशादिरिति मिश्रोक्तं तु न युक्तं भाष्यस्वारस्येनादेशस्यैव यत्वमिति लाभात् ॥

(१६१६ प्रयोजनवार्तिकम् ॥६॥)

॥ * ॥ रुविधिः पुंख्याने ॥ * ॥

(भाष्यम्) **पुंख्यानमिति रुविधिर्न भवति ॥**

(प्रदीपः) **पुंख्यानमिति । पुमःखय्यम्परे इति** रुत्वं न भवति यत्वस्यासिद्धत्वादम्परत्वाभावात् ॥

(१६१७ प्रयोजनवार्तिकम् ॥७॥)

॥ * ॥ णत्वं पर्याख्याने ॥ * ॥

(भाष्यम्) **पर्याख्यानमिति णत्वं न भवति ॥**

(प्रदीपः) **णत्वमिति । ख्याप्रकथन इत्यस्यापि** परस्य **लुव्योगाप्रख्यानादिति** निपातनाण्णत्वाभावः ॥

(उद्द्योतः) निपातनादिति । सौत्रप्रयोगस्यादेशेऽप्युपपत्तेश्चिन्त्यमेतत् ॥ णत्वेति । कृत्यच इति प्राप्तिः ॥

(१६१८ प्रयोजनवार्तिकम् ॥ ८ ॥)

॥ * ॥ सस्थानत्वं नमः ख्यात्रे ॥ * ॥

(भाष्यम्) **नमः ख्यात्र इति सस्थानत्वं न भवति॥**

(प्रदीपः) **सस्थानत्वमिति ।** जिह्वामूलीयस्येयं पूर्वाचार्यसंज्ञा । **शर्परे विसर्जनीय** इत्येवात्र भवति ॥

(उद्द्योतः) इयं जिह्वामूलीयत्वमित्यर्थः ॥

(१६१९ आदेशप्रतिषेधवार्तिकम् ॥९॥)

॥ * ॥ वर्जने प्रतिषेधः ॥

(भाष्यम्) **वर्जने प्रतिषेधो वक्तव्यः । अवसंचक्ष्याः । परिसंचक्ष्याः ॥**

(१६२० आदेशप्रतिषेधवार्तिकम् ॥ १० ॥)

॥ * ॥ असनयोश्च ॥ * ॥

(भाष्यम्) असनयोश्च प्रतिषेधो वक्तव्यः । नृचक्षा रक्षः । विचक्षण इति ॥

(प्रदीपः) नृचक्षारक्ष इति प्रयोगश्छान्दसः । भाषायां तु नृचक्षो रक्ष इति ॥ विचक्षण इति । अनुदात्तेतश्च हलादेरिति युच् ॥

(उद्द्योतः) नृचक्षा इति प्रयोगे रक्षोविशेषणत्वे नपुंसकत्वेन दीर्घानुपपत्तिरत आह—छान्दस इति ॥

(१६२१ वार्तिकम् ॥ ११ ॥)

॥ * ॥ बहुलं तणि ॥ * ॥

(भाष्यम्) बहुलं तणीति वक्तव्यम् ॥ किमिदं तणीति ? । संज्ञाछन्दसोर्ग्रहणम् ॥

किं प्रयोजनम् ? ॥

(१६२२ प्रयोजनवार्तिकम् ॥ १२ ॥)

॥ * ॥ अन्नवधकगात्रविचक्षणाजिराद्यर्थम् ॥ * ॥

(भाष्यम्) अघ्न—अन्नम् ॥ वधक—वधकम् ॥ गात्र—गात्रं पश्य ॥ विचक्षण—विचक्षणः ॥ अजिर अजिरे तिष्ठति । चक्षि ॥ ५४ ॥

(प्रदीपः) बहुलमिति । सर्वप्रकरणापेक्षमेतदुच्यते । अन्नशब्दे जग्ध्यभावः ॥ वधकमिति । ण्वुलि वधादेशः ॥ गात्रमिति । इण औणादिके ष्ट्रनि गादेशः ॥ विचक्षणे ख्याञभावः ॥ अजिरे वीभावाभावः । अजिरशिशिरेति निपातनमनपेक्ष्यैतदुक्तम् ॥ ५४ ॥

(उद्द्योतः) नन्वत्र विचक्षणशब्दादन्येषामुपयोगं न पश्याम इत्यत आह—सर्वप्रकरणेति ॥ अनपेक्ष्येति । तेषां सूत्राणामाधुनिकत्वादनपेक्षेति भावः ॥ ५४ ॥

(३६४ आदेशसूत्रम् ॥ २ । ४ । १ आ. २९)

५८७ अजेर्व्यघञपोः ॥ २।४।५६ ॥

(क्यपि प्रतिषेधाधिकरणम्)

(१६२३ वार्तिकम् ॥ १ ॥)

॥ * ॥ घञपोः प्रतिषेधे क्यप उपसंख्यानम् ॥ * ॥

(भाष्यम्) घञपोः प्रतिषेधे क्यप उपसंख्यानं कर्तव्यम् । इहापि यथा स्यात्—समजनं समज्येति ॥

(उद्द्योतः) अजेर्व्य ॥ ५६ ॥ क्यप उपसंख्यानमिति भाष्ये—अधिकरणस्य शेषत्वविवक्षायां षष्ठी ॥

(आक्षेपभाष्यम्)

तत्तर्हि वक्तव्यम् ? ॥

(समाधानभाष्यम्)

न वक्तव्यम् । अपीत्येव भविष्यति ॥ कथम् ? । अपीति नेदं प्रत्ययग्रहणम् ॥ किं तर्हि ? । प्रत्याहारग्रहणम् ॥ क्व सन्निविष्टानां प्रत्याहारः ? । अपो अकारात्प्रभृत्या क्यपः पकारात् ॥

(आक्षेपभाष्यम्)

यदि प्रत्याहारग्रहणम्, संवीतिर्न सिध्यति ॥

(समाधानभाष्यम्)

एवं तर्हि नार्थ उपसंख्यानेन नापि घञपोः प्रतिषेधेन । इदमस्ति "चक्षिङः ख्याञ्" "वा लिटि" इति । ततो वक्ष्यामि "अजेर्वी" अजेर्वीभावो भवति वा । व्यवस्थितविभाषा "वा" इति । तेनेह च भविष्यति—प्रवेता, प्रवेतुम्, प्रवीतो रथः, संवीतिः । इह च न भविष्यति—समाजः समजः, उदाजः उदजः, समजनम् उदजनं समज्येति । तत्रायमप्यर्थः—इदमपि सिद्धं भवति प्राजितेति ॥

(प्रदीपः) अजेर्वी ॥ ५६ ॥ इदमपीति । वलादावार्धधातुके विकल्पः सिध्यतीति भावः ॥

(उद्द्योतः) वलादाविति । यद्यपि भाष्ये तृच्येव विकल्पो लभ्यते, तथापि पादस्य पदाज्यातीति निर्देशेनेह च न भविष्यति समाज इत्यपि भाष्यस्योपलक्षणताया आवश्यकत्वेनेदमपि तथैव वृत्त्यादिप्रामाण्यादिति भावः ॥

(आक्षेपभाष्यम्)

किंच भो इष्यत एतद्रूपम् ? ॥

(समाधानभाष्यम्)

बाढमिष्यते । एवं हि कश्चिद्वैयाकरण आह—कोऽस्य रथस्य प्रवेतेति ॥

सूत आह—अहमायुष्मन्नस्य रथस्य प्राजितेति ॥

वैयाकरण आह—अपशब्द इति ॥

सूत आह—प्राप्तिज्ञो देवानांप्रियः, न त्विष्टिज्ञः इष्यत एतद्रूपमिति ॥

वैयाकरण आह—अहो नु खल्वनेन दुरुतेन बाध्यामह इति ॥

सूत आह—न खलु वेञः सूतः, सुवतेरेव सूतः । यदि सुवतेः कुत्सा प्रयोक्तव्या, दुःसूतेनेति वक्तव्यम् ॥

(प्रदीपः) सूत आहेति । प्रयोगदर्शनेन विकल्पं प्रद-

यति ॥ प्राप्तिज्ञ इति । सौत्रीमेव प्राप्तिं भवान् जानाति । न त्वाचार्याणामिष्टिमित्यर्थः ॥ देवानांप्रिय इति । देवशब्दो मूर्खवाची । मूर्खाणाञ्च प्रिया मूर्खा एव भवन्ति । अथ वा सुखासक्ततया शास्त्रेऽनभियोगोऽनेन प्रतिपाद्यते ॥ पराजितत्वादमर्षणाह—अहो नु खल्विति । वेञ उत इति यद्रूपं सास्य संज्ञा । पूजायां च सुशब्द इति मत्वा कुत्साप्रतिपादनायाह—दुरुतेनेति ॥ सूत आहेति । षू प्रेरणे इत्यस्माद् बहुलवचनात्कर्तरि गत्यादिसूत्रे चकारस्यानुक्तसमुच्चयार्थत्वाद्वर्तमाने क्तः । रथवाहस्य रथे प्रेरणात् सूत इति संज्ञा ॥

(उद्द्योतः) वर्तमाने क्त इति । तेन रथं सूत इति न भवति ॥

(आक्षेपभाष्यम्)

न तर्हीदानीमिदं वक्तव्यम् "वा यौ" इति ॥

(उद्द्योतः) न तर्हीदानीं वायाविति वक्तव्यमिति । व्यवस्थितविभाषयैव यौ वीभावविकल्पस्य सिद्धत्वादिति भावः ॥

(समाधानभाष्यम्)

वक्तव्यं च ॥ किं प्रयोजनम् ? । नेयं विभाषा । किं तर्हि ? । आदेशो विधीयते—वा इत्ययमादेशो भवत्यजेर्यौ परतः । वायुरिति ॥ अजेर्व्यी ॥ ५६ ॥

(प्रदीपः) वायुरिति । यजिमनीति बाहुलकादुण्वि रूपम् ॥ ५६ ॥

(उद्द्योतः) वायुरिति । यदि वातेरुणि वायुः प्रकारान्तरेण सिध्यति, तर्हि घञप्ययप्ग्रहणवदिदमपि व्यर्थमिति कश्चित् ॥ ५६ ॥

(इत्यार्धधातुकाधिकारप्रकरणम्)

(अथ लुक्प्रकरणम्)

(३६५ लुग्विधायकसूत्रम् ॥ २ । ४ । १ आ. ३०)

५८९ ण्यक्षत्रियार्षञितो यूनि लुगणिञोः ॥ २।४।५८ ॥

(१६२४ वार्तिकम् ॥ १ ॥)

॥ * ॥ अणिञोर्लुकि तद्राजाद्युवप्रत्ययस्योपसंख्यानम् ॥ * ॥

(भाष्यम्) अणिञोर्लुकि तद्राजाद्युवप्रत्ययस्योपसंख्यानं कर्तव्यम् । बौधिः पिता बौधिः पुत्रः । औदुम्बरिः पिता औदुम्बरिः पुत्रः ॥

(प्रदीपः) ण्यक्षत्रिया ॥ ५८ ॥ तद्राजादिति । ते तद्राजा इति तद्राजसंज्ञकप्रत्ययान्तात्परस्येत्यर्थः ॥ बौधिरिति बुधोदुम्बरशब्दाभ्यां साल्वावयवलक्षण इञ् तदन्ताद्यूनि यञिञोश्चेति फक् तस्य लुक् ॥

(न्यासान्तरभाष्यम्)

अपर आह—

(१६२५ वार्तिकन्यासान्तरम् ॥ २ ॥)

॥ * ॥ अणिञोर्लुकि क्षत्रियगोत्रमात्राद्युवप्रत्ययस्योपसंख्यानम् ॥ * ॥

(व्याख्याभाष्यम्)

अणिञोर्लुकि क्षत्रियगोत्रमात्राद्युवप्रत्ययस्योपसंख्यानं कर्तव्यमिति । जाबालिः पिता जाबालिः पुत्रः ॥

(प्रदीपः) जाबालिरिति । जबालस्यापत्यम् । अत इञ् स च तद्राजो न भवतीति द्वितीयं वचनमारब्धम् । तेनेञन्तात् फको लुक् ॥

(न्यासान्तरभाष्यम्)

अपर आह—

(१६२६ अपरमतेनवार्तिकम् ॥ ३ ॥)

॥ * ॥ अब्राह्मणगोत्रमात्राद्युवप्रत्ययस्योपसंख्यानम् ॥ * ॥

(व्याख्याभाष्यम्)

अब्राह्मणगोत्रमात्राद्युवप्रत्ययस्योपसंख्यानं कर्तव्यमिति । किंप्रयोजनम् ? । इदमपि सिद्धं भवति—भाण्डिजङ्घिः पिता भाण्डिजङ्घिः पुत्रः । कार्णखरकिः पिता कार्णखरकिः पुत्रः ॥

इति श्रीभगवत्पतञ्जलिविरचिते व्याकरणमहाभाष्ये द्वितीयस्याध्यायस्य चतुर्थपादे प्रथममाह्निकम् ॥

(प्रदीपः) अब्राह्मणगोत्रमात्रादिति । तेन वैश्यगोत्रादपि सिध्यति । व्यापकत्वाच्चेदमेव वचनं प्रमाणम् । भण्डिजङ्घकर्णखरकौ वैश्यौ ॥ ५८ ॥

इत्युपाध्यायजैयटपुत्रकैयटकृते भाष्यप्रदीपे द्वितीयाध्यायस्य चतुर्थपादे प्रथमाह्निकम् ॥

(उद्द्योतः) ण्यक्षत्रिया ॥ ५८ ॥ अत्रत्यवार्त्तिकानि अनणिञर्थानीत्याहुः ॥ पैलादिदर्शनादिमानि सिद्धानीति वृत्तिः ॥५८॥

इति श्रीशिवभट्टसुतसतीगर्भजनागेशभट्टकृते भाष्यप्रदीपोद्द्योते द्वितीयाध्यायस्य चतुर्थे पादे प्रथममाह्निकम् ॥

द्वितीयाध्यायस्य चतुर्थपादे द्वितीयमाह्निकम् ।

(३६६ लुक्सूत्रम् ॥ २। ४। २ आ. १ सू०)

५९३ तद्राजस्य बहुषु तेनैवास्त्रियाम् ॥ २।४।६२ ॥

(प्रत्ययपक्षदूषणाधिकरणम्)

(१६२७ आक्षेपवार्तिकम् ॥ १ ॥)

॥ * ॥ तद्राजादीनां लुकि समासबहुत्वे प्रतिषेधः ॥ * ॥

(भाष्यम्) तद्राजादीनां लुकि समासबहुत्वे प्रतिषेधो वक्तव्यः । प्रिय आङ्गा एषां त इमे प्रियाङ्गाः । प्रियो वाङ्ग एषां त इमे प्रियवाङ्गा इति ॥

(प्रदीपः) तद्राज ॥ ६२ ॥ इह 'तेनैव'-ग्रहणाद्बहुशब्देन बहुवचनमुच्यत इति लक्ष्यते । संज्ञानां चैकदेशपदप्रयोगो दृश्यते यथा भीमसेनो भीम इति । अर्थग्रहणे तु तेनैवेति न वक्तव्यं प्रियवाङ्गा इत्यत्र बहुत्वे तद्राजस्य वृत्त्यभावाल्लुकः प्रसङ्गाभावात् ॥ बहुवचनं तु परमिति लुक्प्रसङ्गे तन्निवृत्तये तेनैव ग्रहणं कर्तव्यम् ॥ अस्त्रियामिति तु प्रतिषेधो बहुवचनग्रहणेऽनुपपन्नः । आङ्ग्यः स्त्रिय इत्यादौ स्त्रीप्रत्ययेन बहुवचनस्य व्यवधानाल्लुकः प्रसङ्गाभावात् । अर्थग्रहणे तु लुक्प्रसक्तोऽस्त्रियामिति निषिध्यते ॥ तदेवं पक्षद्वयस्यापि लिङ्गदर्शनात्तद्गुणदोषनिरूपणाय विचारः क्रियते तत्र पूर्वं प्रत्ययपक्षो विचार्यते ॥ तद्राजादीनामित्यादिशब्देन वक्ष्यमाणा लुग्भाजो गृह्यन्ते ॥ समासबहुत्व इति । समासार्थबहुत्वे इत्यर्थः ॥

(उद्द्योतः) तद्राजस्य ॥ ६२ ॥ ननु बहुत्ववदर्थप्रतिपादकतद्राजस्यानेन लुग्विधानात् प्रियाङ्गा इत्यादावस्य प्राप्तिरेव नेत्यत आह—इहेति ॥ बहुवचनशब्दस्य प्रत्ययविशेषे संकेतिततया बहुशब्देन तत्प्रतीतिः कथमत आह—संज्ञानां चेति । *विनापि प्रत्ययं पूर्वोत्तरपदयोर्लोपः* इति वचनादिति भावः ॥ प्रत्ययग्रहणपक्षे तद्राजार्थेनैव कृतं यद्बहुत्वं तत्प्रतिपादके बहुवचने परत इत्यर्थः । तत्पदेन तद्राजपरामर्शिना तदर्थो लक्ष्यत इति बोध्यम् । अर्थग्रहणपक्षे बहुषु वर्तमानस्य तद्राजस्येत्यर्थः ॥ प्रत्ययग्रहणपक्षस्य तेनैवेति लिङ्गमुक्त्वा अर्थग्रहणपक्षस्य लिङ्गमाह—अस्त्रियामिति ॥ तत्र पूर्वमिति । निषेध्यत्वादिति भावः ॥ प्रियवाङ्गा इति समासस्यैकत्वादाह—समासार्थेति ॥

(प्रत्याक्षेपभाष्यम्)

किमुच्यते समासबहुत्वे प्रतिषेध इति । यदा 'तेनैव चेत्कृतं बहुत्वम्' इत्युच्यते । न चात्र तेनैव कृतं बहुत्वम् ? ॥

(प्रदीपः) नचात्रेति । अन्यपदार्थकृतत्वादत्र बहुत्वस्य ॥

(उद्द्योतः) तेनैव चेत्कृतं बहुत्वमिति भाष्ये तन्मात्रार्थगतबहुत्वार्थके वचने परत इत्यर्थः ॥ अन्येति । अन्यपदार्थश्च न तद्राजान्तमात्रार्थः । किन्तु समुदायार्थ इति भावः ॥

(प्रत्याक्षेपसमाधानभाष्यम्)

भवति वै किंचिद्—आचार्याः क्रियमाणमपि चोदयन्ति—तद्वा कर्तव्यम्—तेनैव चेद्बहुत्वमिति । समासबहुत्वे वा प्रतिषेध इति ॥

(प्रदीपः) भवति वै किं चिदिति । एतावदेकं वाक्यम् । एवंविधं किं चिद्भवतीत्यर्थः ॥ किं तदित्याह—आचार्या इति । सूत्रे क्रियमाणमपि कुर्वन्तीत्यर्थः ॥ बहुवचनपक्षे सर्वथा वचनेनैव दोषो निराकार्य इति प्रतिपादनमस्योपन्यासस्य फलम् ॥

(उद्द्योतः) एकवाक्यत्वासंभवादाह—एतावदिति । प्रश्नरूपार्थानुपपत्तेश्चुदेः क्रियामात्रे लक्षणेत्याशयेनाह—कुर्वन्तीत्यर्थ इति ॥ सर्वथा वचनेनैवेति । अत्र पक्षे तेनैवेत्यवश्यं कार्यमिति वार्तिकतात्पर्यमित्यर्थः ॥

(१६२८ वार्तिकम् ॥ २ ॥)

॥ * ॥ अबहुत्वे लुग्वचनम् ॥ * ॥

(भाष्यम्) अबहुत्वे च लुग्वक्तव्यः । अतिक्रान्तः अङ्गानत्यङ्ग इति । बहुवचने परतो यस्तद्राज इत्येवं च कृत्वा चोद्यते ॥

(प्रदीपः) प्रत्ययपक्षे दोषोद्भावनेनार्थग्रहणं स्थापयति—अबहुत्व इति । समासार्थस्याबहुत्वाद् बहुवचनपरत्वाभावेऽपि लुग्वक्तव्यः प्रत्ययश्चेद्बहुत्व उत्पन्न इत्यर्थः ॥

(उद्द्योतः) अबहुत्वे इत्यस्य बहुवचनपरत्वाभावे इत्यर्थ इत्याह—समासेति ॥

(आक्षेपभाष्यम्)

अथ किमर्थं पुनरिदम्, न बहुवचन इत्येव सिद्धम् ? ॥

(प्रदीपः) न बहुवचन इत्येवेति । शसमेवाश्रित्यान्तरङ्गत्वात्पूर्वं तद्राजस्य लुक्करिष्यत इति भावः ॥

(उद्द्योतः) सोर्बहुवचनत्वाभावादसङ्गतिमाशङ्क्याह—शसमेवेति ।

(समाधानभाष्यम्)

न सिध्यति । बहुवचन इत्युच्यते । न चात्र बहुवचनं पश्यामः ॥

(प्रदीपः) न चात्रेति । अन्तरङ्गानपि विधीन्बहुपो धातुप्रातिपदिकयोरित्ययं लुक् प्रत्ययोत्तरपदयोश्चेति ज्ञापकादसैवात्र संभवाद्बाधत इति भावः ॥

(उद्द्योतः) भाष्ये न चात्रेति । लुका लुप्तत्वादिति भावः ॥

अन्तरङ्गानपीति न्यायादिति तात्पर्यम् ॥ नन्वन्तरङ्गानिति न्याये-नास्यापि लुको ग्रहणेनेदमनुपपन्नमत आह—असंभवाच्चेति । ज्ञापकस्य विशेषापेक्षत्वादिति भावः ॥ वस्तुतश्चिन्त्यमेतत् । एङ्ह्रस्वात्संबुद्धेरित्यादिसूत्रस्थभाष्यविरोधादिति स्पष्टं शब्देन्दुशेखरे ॥ अनेनापि न्यायेन कार्यान्तरनिमित्तविनाशकलुक एतदपेक्षया प्राबल्यं बोध्यते तत एव ज्ञापकादिति नायं लुक्सुग्लुगपेक्षया बलवानिति तु भाष्याशयः ॥

(समाधानबाधकभाष्यम्)

प्रत्ययलक्षणेन ॥

(समाधानसाधकभाष्यम्)

'न लुमता तस्मिन्' इति प्रत्ययलक्षणस्य प्रतिषेधः ॥

(समाधानबाधकभाष्यम्)

"न लुमताङ्गस्य" इति वक्ष्यामि ॥

(प्रदीपः) न लुमताङ्गस्येति वक्ष्यामीति । यथास्थितमेव न्यासमेवं व्याख्यास्यामि । लुमता लुप्ते यः प्रत्ययस्तस्मिन्यदङ्गं तस्य यत्कार्यमङ्गाधिकारविहितमन्यद्वा तन्न भवति। लुक् च प्रत्ययस्य कार्यम्, न समस्तस्याङ्गस्येति प्रत्ययलक्षणेन भविष्यति ॥

(उद्द्योतः) यथास्थितमेवेति । एवधानङ्गाधिकारविहितकार्ये प्रतिषेधाय वार्तिककृता न्यासान्तरमारब्धम्, तस्यार्थस्य सूत्रेणैव लाभे वार्तिकं न कार्यम्, सूत्रस्य च न प्रातिस्विकोद्देश्यककार्याभावादिति भावः ॥ नसमस्तस्येति । न संपूर्णस्येत्यर्थः ॥

(समाधानसाधकभाष्यम्)

नैवं शक्यम् । इह हि दोषः स्यात्—पञ्चभिर्गार्गीभिः क्रीतः पटः पञ्चगार्ग्यो दशगार्ग्यः ॥

(प्रदीपः) पञ्चभिरिति । क्रीतार्थस्यार्हीयस्य ठकोऽध्यर्द्धपूर्वेति लुक् । लुकद्धितलुकीति स्त्रीप्रत्ययस्य लुक् । तत्र प्रत्ययलक्षणेन भिसमाश्रित्यात्र पक्षे यञञोश्चेति लुक् प्राप्नोति । न हि यञ्लुगङ्गस्य कार्यमिति पञ्चगर्ग इति स्यात् । पञ्चगार्ग्य इति चेष्यत इत्यर्थः । अस्त्रियामिति चात्र प्रतिषेधो न भवत्यर्थान्तरे पुंसि संक्रान्तत्वाद्वृत्तिपदार्थस्येत्याहुः ॥

(उद्द्योतः) इतिचेष्यत इति । तस्मादङ्गस्य तदवयवस्य वा कार्ये निषेध इत्यर्थः ॥ अस्त्रियामिति चात्रेति । एतदर्थमेवास्त्रियामिति करणे तु गौरवमिति भावः । न च ङीलुकः स्थानिवत्त्वाद्बहुवचनपरत्वाभावः । लुकि तन्निषेधात् ॥

(१६२९ दूषणवार्तिकम् ॥ ३ ॥)

॥ * ॥ द्वन्द्वेऽबहुषु लुग्वचनम् ॥ * ॥

(भाष्यम्) द्वन्द्वे अबहुषु लुग्वक्तव्यः । गर्गवत्सवाजा इति । इह च लुग्वक्तव्यः—गर्गेभ्य आगतं गर्गरूप्यं गर्गमयमिति । इह चात्रय इति उदात्तनिवृत्तिस्वरः प्राप्नोति ॥

(प्रदीपः) द्वन्द्वेऽबहुष्वित्यत्राकारप्रश्लेषः । गार्ग्यश्च वात्स्यश्च वाज्यश्चेति द्वन्द्वः । अत्रैकैकस्य बहुवचनपरत्वं नास्ति यच्च समासाद्बहुवचनमुत्पद्यते तदन्त्यादेव परं न सर्वेभ्यः । प्रत्ययनिर्देशपक्षे तस्मिन्निति निर्दिष्ट इति परिभाषोपस्थानाद्व्यवहितस्य लुकोऽप्रसङ्गः ॥ गर्गरूप्यमिति । सुबन्तेन केवलं वाक्यं क्रियते ॥ प्रत्ययस्तु प्रातिपदिकाधिकारात्प्रातिपदिकादेवोत्पद्यत इति बहुवचनपरत्वाभावाल्लुङ् प्राप्नोति ॥ अत्रय इति । अत्रेरपत्यानि इतश्चानिञः इति ढक् कित इत्यन्तोदात्तत्वम् । तत्र यदि जसि परतो लुक् क्रियते तदा अनुदात्तस्य च यत्रोदात्तलोप इति जस उदात्तत्वप्रसङ्गः ॥

(उद्द्योतः) गार्ग्यश्चेति । युगपदधिकरणवचनताया दूषितत्वादेकवचनान्तेन विग्रहः ॥ अबहुष्विति भाष्यस्य न विद्यते बहुवचनं परं येभ्यस्तेषु वर्तिपदेष्वित्यर्थः ॥ सुबन्तात्तद्धिते बहुवचनपरत्वसत्त्वादाह—प्रातिपदिकादेवेति ॥ न लुमतेति निषेधात्प्रत्ययलक्षणाभावेन लुकि न सिध्येदित्येव भाष्याशय इत्यपि कश्चित् । तत्तु सामर्थ्ये च सुबन्तेनेत्युत्तरभाष्यविरुद्धम् ॥ जसि परत इति । उदात्तलोपशब्देन नोदात्तघटितलोप उच्यते इति भावः ॥

(प्रत्ययार्थबहुत्वस्थापनाधिकरणम्)

(१६३० समाधानवार्तिकम् ॥ ४ ॥)

॥ * ॥ सिद्धं तु प्रत्ययार्थबहुत्वे लुग्वचनात् ॥ * ॥

(भाष्यम्) सिद्धमेतत् ॥ कथम् ? । प्रत्ययार्थबहुत्वे लुग्वक्तव्यः ॥

(प्रदीपः) अर्थनिर्देशाश्रयेण परिहारमाह—सिद्धं त्विति । लुग्वचनात् लुग्व्याख्यानादित्यर्थः ॥

(उद्द्योतः) अपूर्ववचनत्वशङ्कां वारयति—व्याख्यानादिति ॥

(प्रत्ययार्थपक्षे गौरवभाष्यम्)

यदि प्रत्ययार्थबहुत्वे लुगुच्यते, तेनापि; 'अस्त्रियाम्' इति वक्तव्यम् । इह मा भूत्—आङ्गयः स्त्रियः वाङ्ग्यः स्त्रिय इति ॥ यस्य पुनर्बहुवचने परतो लुगुच्यते तस्य ईकारेण व्यवहितत्वान्न भविष्यति॥

(प्रत्ययपक्षेपि गौरवभाष्यम्)

यस्यापि तु बहुवचने परतो लुगुच्यते, तेनापि 'अस्त्रियाम्' इति वक्तव्यम् । आम्बष्ठ्याः स्त्रियः सौवीर्याः स्त्रिय इत्येवमर्थम् ॥

(प्रदीपः) आम्बष्ठ्या इति । आम्बष्ठस्यापत्यानि बह्व्यः स्त्रिय इति वृद्धेत्कोसलाजादाञ्ञ्यङिति ञ्यङ् । यङश्चापिति चाप् । एकादेशः । स चान्तवद्भावान्न व्यवधायक इति लुक्प्रसङ्गे प्रत्ययपक्षवादिनाप्यस्त्रियामिति प्रतिषेधो वक्तव्य इत्यर्थः ॥

(उद्द्योतः) अम्बष्ठस्येति । क्षत्रियनामेदम्, अतो वा नामधेयस्येति वृद्धत्वम् । आम्बष्ठस्येति पाठे तु सम्यगेव ॥

(बाधकभाष्यम्)

अत्रापि चापा व्यवधानम् ॥

(साधकभाष्यम्)

एकादेशे कृते नास्ति व्यवधानम् ॥

(बाधकभाष्यम्)

एकादेशः पूर्वविधौ स्थानिवद्भवतीति स्थानिवद्भावाद्व्यवधानमेव ॥

(प्रदीपः) **एकादेश इति । अचः परस्मिन्निति** स्थानिवद्भावः ॥ तदेवमर्थनिर्देशपक्ष **एवाऽस्त्रियामिति** वक्तव्यम् ॥

(उद्द्योतः) अचः **परस्मिन्निति** । यद्यपि अन्तवद्भावेन त्वावन्तस्यायं विधिरिति न पूर्वविधित्वं तथापि पूर्वविधावित्यस्य पूर्वोद्देश्यकविधावित्यर्थादस्त्येव । यद्यपि यशब्दोऽपि स्थान्येव स कथं ततः पूर्वस्तथापि यत्किञ्चित्स्थानिभूतपूर्वत्वमस्त्येव । स्थानिभूतादचः पूर्वोऽस्थानिभूत एव गृह्यते इत्यत्र न मानं स्थानिनि पृथग्भूते सत्यभवतो लुक एकादेशेऽप्यभावातिदेशो बोध्यः ॥ एतेन त्वावन्तस्य कथं चापा व्यवधानमित्यपास्तम् । **तदेवमिति । अस्त्रियामित्येवार्थनिर्देशपक्षस्य** ज्ञापकमिति भावः ॥

(१६३१ अर्थपक्षे दूषणवार्तिकम् ॥ ५ ॥)

॥ * ॥ द्वन्द्वेऽबहुषु लुग्वचनम् ॥ * ॥

(भाष्यम्) **द्वन्द्वे अबहुषु लुग्वक्तव्यः । गर्गवत्सवाजा इति ॥**

(प्रदीपः) **द्वन्द्व इति** । एकस्मिन्नेवार्थे प्रत्ययोत्पत्तौ सत्यां बहुत्वाभावात् । प्रत्ययपक्षे त्वन्त्यस्य तावन्निभ्यतीति मन्यते ॥

(उद्द्योतः) नन्वयं दोषो बहुवचनग्रहणेऽपीति कथं परं प्रत्ययस्योपन्यासोऽत आह—**अन्त्यस्य तावदिति** । एवंचार्थपक्षे त्रयाणामपि लुग्वाच्यः । प्रत्ययपक्षे त्वनन्त्ययोरेवेति भावः ॥

(१६३२ अर्थपक्षदूषणवार्तिकम् ॥ ६ ॥)

॥ * गोत्रस्य बहुषु लोपिनो बहुवचनान्तस्य प्रवृत्तौ द्व्येकयोरलुक् ॥ * ॥

(भाष्यम्) **गोत्रस्य बहुषु लोपिनो बहुवचनान्तस्य प्रवृत्तौ द्व्येकयोरलुग्वक्तव्यः । बिदानामपत्यं माणवको बैदः । बैदौ ॥**

(प्रदीपः) अर्थपक्ष एव दोषमाह—**गोत्रस्येति** । अपत्यप्रत्ययो लोपभाग्यदा बहुष्वर्थेषूत्पन्नो युवापत्यविवक्षायामर्थान्तरे द्वित्वविशिष्टे एकत्वविशिष्टे वा संक्रामति तदा बहुषु तस्योत्पन्नत्वाल्लुक्प्राप्तावलुग्वक्तव्यः । प्रत्ययपक्षे तु बहुवचनपरत्वाभावाल्लुङ्न भवति ॥ **द्व्येकयोरिति** । द्व्येकशब्दौ द्वित्वैकत्ववृत्ती उपात्तौ । अन्यथा बहुवचनं स्यात् ॥ **बैद इति । बिदस्यापत्यानि बहूनि इत्यञ्प्रत्ययः । तदन्तादून्यत इञि**तीञ् तस्य **ण्यक्षत्रियार्षञित** इति लुक् ॥

(उद्द्योतः) **बहुष्वर्थेषूत्पन्न इति** । यदा विशेष्यांशेऽपि न संख्यामानं तदैकशेषेण बहुष्वर्थेषु स्थित इत्यर्थो बोध्यः ॥ **तस्य** गोत्रप्रत्ययस्य ॥ **बहुवचनपरत्वाभावादिति** । प्रत्ययलक्षणं तु **न लुमतेति** निषिद्धमिति भावः ॥ ननु **अस्त्रियामित्यस्य** यथाऽर्थान्तरानुपसंक्रान्तस्त्रीविषयता तथा बहुष्वित्यस्यार्थान्तरानुपसंक्रान्तबहुत्वविषयकत्वात्नात्र दोषः । द्व्येकयोस्तस्योपसंक्रान्तत्वादिति चेन्न । बहुष्विति बहुवचनेन सर्वस्यापि बहुत्वस्य ग्रहादित्याशयः । अतएवात्यङ्ग इत्यादिसिद्धिः । इदमेव ध्वनयितुं सूत्रकृताऽस्त्रियामिति विभिन्नविभक्तिनिर्देशः कृतः । प्रकृतसूत्रे वार्तिककरणादेतदुदाहरणाविषयीभूतं अङ्गानामपत्यं माणवक आङ्ग इत्यप्युदाहरणं बोध्यम् ॥ **गोत्रेऽलुगचीति** समाधानमपि साधारणमेव, एतत्सूत्रविहितस्यापि तेनालुग्विधानात् । यत्तु तत्र **लक्षणप्रतिपदोक्तपरि**भाषया **यस्कादिभ्यो गोत्र** इत्येतत्प्रकरणस्यत्वात् । इतएव तत्र बहुष्वित्यादीनामनुवृत्तेः श्रोतृवक्तृबुद्धिस्थतया एव प्रकरणत्वात् । अत एव **गोत्रेऽलुगचीति** सूत्रे **भूम्नि प्राप्तस्य लुकोऽलुगिति** भगवता वक्ष्यते ॥ उत्तरसूत्रोदाहरणं तु 'उत्तरसूत्रविषयेऽप्ययं विचारस्तुल्यः' इति बोधयितुम् । अत एवोपक्रमे **तद्राजादीनामित्युक्तम्** ॥

(आक्षेपभाष्यम्)

किमर्थमिदम् । नाचीत्येवालुक् सिद्धः ? ॥

(प्रदीपः) **नाचीत्येवेति । गोत्रेऽलुगचीत्यनेन ॥**

(समाधानभाष्यम्)

अचीत्युच्यते । न चात्राजादिं पश्यामः ॥

(उद्द्योतः) भाष्ये—**नचात्राजादिमिति । यस्मिन्विधि**रिति परिभाषालब्धमेतत् ॥

(समाधानबाधकभाष्यम्)

प्रत्ययलक्षणेन ॥

(समाधानसाधकभाष्यम्)

वर्णाश्रये नास्ति प्रत्ययलक्षणम् ॥

(उद्द्योतः) **वर्णाश्रये इति** । अजादिग्रामदीव्यतीयविषये इत्यर्थेऽपि लुका विषयस्यापहारादोष एवेति बोध्यम् । भाष्यधारणमेव हि **विषयः** ॥

(१६३३ वार्तिकम् ॥ ७ ॥)

॥ * ॥ एकवचनद्विवचनान्तस्य प्रवृत्तौ बहुषु लोपो यूनि ॥ * ॥

(भाष्यम्) **एकवचनद्विवचनान्तस्य प्रवृत्तौ बहुषु लोपो यूनि वक्तव्यः । बैदस्यापत्यं बहवो माणवका बिदाः । बैदयोर्वा बिदाः । अञ् यो बहुषु यञ्यो बहुष्वित्युच्यमानो लुङ्न प्राप्नोति ॥**

(उद्योतः) अतिव्याप्तिमुक्त्वा तत्रैव पक्षेऽव्याप्तिमाह—भाष्ये—**एकेति**। बहुषु लोपी यस्तद्धितस्तदन्तप्रकृतिकैकवचनान्तस्य युवबहुत्वविषयकप्रत्ययविषये प्रकृतित्वेन प्रवृत्तौ सत्यां तदवयवस्य तद्धितस्य लुग्वक्तव्य इत्यर्थः॥

(आक्षेपबाधकभाष्यम्)

मा भूदेवम्। अञन्तं यद्बहुषु यञन्तं यद्बहुष्विस्येवं भविष्यति॥

(प्रदीपः) **अञन्तमिति**। प्रत्ययग्रहणपरिभाषया तदन्तत्वे स्थिते बहुष्विति विशेषणं तदन्तस्यैवेति मन्यते॥

(आक्षेपसाधकभाष्यम्)

नैवं शक्यम्। इह हि दोषः स्यात्—काश्यपप्रतिकृतयः काश्यपा इति॥

(प्रदीपः) **काश्यपा इति**। कश्यपस्यापत्यं गोत्रमिति बिदादित्वादञ् ततः काश्यप इव तत्प्रतिकृतय इत्यत्रार्थे **इवे प्रतिकृताविति** कन्प्रत्ययस्तस्य **जीविकार्थे चापण्ये** इति वा **देवपथादिष्वर्चासु पूजनार्थासु चित्रकर्मध्वजेष्विति** पाठाद्वा लुप्। एतदञन्तं बहुषु वर्तत इति लुक्प्रसङ्गः। अञ्प्रत्ययस्त्वेकस्मिन्नेवापत्य उत्पन्न इत्यञ्यो बहुष्विति विज्ञायमाने नास्ति लुक्प्राप्तिस्तस्मात्तदन्तविधिर्नाभ्युपगन्तव्यः। प्रत्ययादर्शनस्यैव लुगादिसंज्ञाविधानात्प्रत्यया एव कार्यभाक्त्वाद् बहुष्वित्यनेन विशेष्यन्ते॥

(उद्योतः) **इति पाठाद्वेति**। अयं चाभियुक्तानां पाठः न त्वेतावता इदमार्षमिति बोध्यम्॥ अञन्तं यद्बहुष्वित्यर्थे न्यायविरोधमप्याह—**प्रत्ययादर्शनस्यैवेति**॥

(अर्थबहुत्वपक्षे दूषणपरिहारभाष्यम्)

ततोयमाह—यस्य प्रत्ययार्थबहुत्वे लुक्। द्वन्द्वेऽबहुषु लुग्वचनमित्यस्य परिहारः—

(१६३४ वार्तिकम्॥ ८॥)

॥*॥ न वा सर्वेषां द्वन्द्वे बह्वर्थत्वात्॥*॥

(भाष्यम्) **न वा एष दोषः। किं कारणम्?। सर्वेषां द्वन्द्वे बह्वर्थत्वात्। सर्वाणि द्वन्द्वे बह्वर्थानि॥ कथम्?। युगपदधिकरणविवक्षायां द्वन्द्वो भवति॥**

(प्रदीपः) इदानीं पक्षद्वयेऽपि क्रमेण परिहार उच्यते—**ततोयमिति**॥ **नवेति**। एकैकं प्रत्ययान्तमनेकार्थाभिधायीति लुक्सिध्यतीत्यर्थः। यश्च तदन्तपक्षे दोषः काश्यप इति स उत्तरत्र परिहरिष्यते॥

(उद्योतः) **ततोयमाहेति**। प्रत्ययार्थबहुत्वे लुगिति यस्य मतं सोऽयं स्वपक्षादोषकथनोत्तरमाहेत्यन्वयः॥ किमाह—**द्वन्द्वे बहुषु लुग्वचनमि**त्यस्य परिहारोऽयमित्याहेत्यर्थः॥ पदानां बह्वर्थत्वेऽपि प्रत्ययस्य बह्वर्थत्वाभावादाह—**प्रत्ययान्तमिति**॥ **स उत्तरत्रेति**। ननु गोत्रग्रहणानुवृत्त्या तत्र दोषं परिहरिष्यति। एवमप्याङ्गस्य प्रतिकृतिय आङ्ग इत्यत्र तदन्तग्रहणपक्षे तद्राजस्येति लुक् प्राप्नोति। नह्यत्रापि गोत्र इति वर्तत इति चेन्न। अत्रापि सूत्रे गोत्र इत्यपकर्षणेनादोषात्। तद्राजस्यापत्यत्वादारोपितगोत्रत्वमस्त्येव॥ यत्तु हरदत्तेनैतदर्थं **तेनैवे**त्यवश्यं कर्त्तव्यमर्थग्रहणपक्षेऽपीत्युक्तम्, तदेतेन परास्तं भाष्यविरुद्धं च॥ वस्तुतः **सर्वाणि द्वन्द्वे बह्वर्थानी**ति भाष्यस्यायमर्थः—आश्रयतया बहुत्ववदर्थप्रतिपादकानीति॥ द्वन्द्वे हि अन्यसंख्याबोधकविभक्त्यभावेन समुदायोत्तरविभक्त्या तेतेऽर्था वस्तुतो बहुत्ववन्त एवोपस्थाप्यन्ते॥ पर्याप्त्या बहुत्ववदर्थप्रतिपादकत्वनिवेशे न किंचिन्मानम्। **युगपदधिकरणविवक्षायामि**त्यस्यापि युगपद्द्रव्याणामेकत्रान्वयविवक्षायां द्वन्द्व इत्येवार्थः॥ युगपदधिकरणवचनतापक्षस्तु द्वन्द्वसूत्रे दूषित एवेति न तमादायास्य ग्रन्थस्य व्याख्योचिता॥

(बहुवचनप्रत्ययपक्षे दूषणपरिहारभाष्यम्)

ततोयमाह—यस्य बहुवचने परतो लुक्, यदि सर्वाणि द्वन्द्वे बह्वर्थानि। अहमपीदमचोद्यं चोद्ये—द्वन्द्वेऽबहुषु लुग्वचनमिति॥ ममापि ह्यत्र सर्वत्र बहुवचनं परं भवति॥

(प्रदीपः) **अचोद्यं चोद्य इति**। अचोदनार्हं वस्तु त्वया अहं चोद्य इत्यर्थः। चोदिः पृच्छत्यर्थत्वाद् दुहियाचीत्यत्रार्थग्रहणाद् द्विकर्मकः॥

(उद्योतः) अपरस्तु युगपदधिकरणवचनतापक्षोऽपि नावलम्बित इति मत्वा स्वपक्षेऽपि दोषाभाव इत्याह—भाष्ये—**ततोऽयमाह यस्य बहुवचने इति**। अर्थवादिकृताव्याप्तिपरिहारानन्तरमित्यर्थः॥ **चोदिः पृच्छयर्थत्वादिति**। व्यापारद्वयार्थत्वेन कर्त्तुरित्येव द्विकर्मकत्वं सिद्धमित्ययं प्रयासो वृथेति वस्तुतत्वम्॥

(बाधकभाष्यम्)

लुकि कृते न प्राप्नोति॥

(प्रदीपः) **लुकि कृत इति**। अन्तरङ्गानपि विधीन्बहिरङ्गो लुग् बाधत इति भावः॥

(परिहारसाधकभाष्यम्)

प्रत्ययलक्षणेन भविष्यति॥

(परिहारबाधकभाष्यम्)

'न लुमता तस्मिन्' इति प्रत्ययलक्षणस्य प्रतिषेधः॥

(परिहारसाधकभाष्यम्)

'न लुमताङ्गस्य' इति वक्ष्यामि॥

(उद्योतः) **न लुमताङ्गस्येति**। तथा चाङ्गोद्देश्यककार्ये एव निषेध इति नात्र निषेधप्रवृत्तिरिति भावः॥ **न लुमता तस्मिन्निति** वार्तिकन्यासेऽपि प्रत्ययाक्षिप्तप्रकृत्युद्देश्यककार्ये एव निषेधो न तु तदवयवोद्देश्यक इति तात्पर्यम्। विषयसप्तमीपक्षेऽपि प्रत्ययलक्षणप्रवृत्तौ बाधकाभाव इति न दोषः। एवं चालङ्ग इत्यपि सिद्धम्॥ अत्रेदं बोध्यम्—युगपदधिकरणवचनताया दूषितत्वात् प्रत्ययपक्षेऽयं दोषः स्थित एवेति॥

(आक्षेपस्मारणभाष्यम्)

ननु चोक्तम्—नैवं शक्यम्। इह हि दोषः स्यात्—पञ्चभिर्गार्गीभिः क्रीतः पटः पञ्चगार्ग्यो दशगार्ग्य इति ॥

(समाधानभाष्यम्)

इष्टमेवैतत्संगृहीतम्—पञ्चगर्गो दशगर्ग इत्येव भवितव्यम् ॥

(प्रदीपः) पञ्चगर्ग इति। प्रत्ययलक्षणेन बहुवचनपरत्वाश्रयो लुक् प्रवर्तत इत्यर्थः ॥

(उद्द्योतः) भाष्ये—पञ्चगर्ग इति ॥ अस्त्रियामिति निषेधस्त्वर्थान्तरानुपसंक्रान्तस्त्रीविषय इत्युक्तम् ॥

(दूषणासंगतिभाष्यम्)

तथेदमपरमचोद्यं चोद्यं—गर्गरूप्यं गर्गमयम्। अत्रापि बहुवचन इत्येव सिद्धम् ॥ कथम्?। समर्थात्तद्धित उत्पद्यते। सामर्थ्यं च सुबन्तेन ॥

(प्रदीपः) समर्थादिति। समर्थानां प्रथमाद्वेत्यधिकारादिति भावः ॥ सामर्थ्यं च सुबन्तेनेति। सुबन्तेन द्वितीयस्य पदस्य संबन्धवत्त्वं पदस्यैव प्रयोगार्हत्वात्। प्रातिपदिकाधिकारस्तु वृद्धादिविशेषणार्थः ॥

(उद्द्योतः) सुबन्तेनेति। तस्य लुक्यप्युक्तन्यायेन प्रत्ययलक्षणत्वाद्बहुवचनपरत्वेन लुक्सिद्ध्या न दोष इति भावः ॥

(परिहारभाष्यम्)

ततोयमाह यस्य प्रत्ययार्थबहुत्वे लुक्। यदि समर्थात्तद्धित उत्पद्यते। अहमपीदमचोद्यं चोद्ये—*गोत्रस्य बहुषु लोपिनो बहुवचनान्तस्य प्रवृत्तौ द्व्येकयोरलुग्* इति। कथम्?। यस्यापि बहुवचने परतो लुक् तेनाप्यलुग्वक्तव्यः। तस्यापि ह्यत्र बहुवचनं परं भवति ॥

(प्रदीपः) अहमिति। यो ह्युभयोर्दोषो न तमेकश्चोद्यः ॥ तस्यापि ह्यत्रेति। प्रत्ययलक्षणेन ॥

(अलुग्वचनबाधकभाष्यम्)

न वक्तव्यः। अचीत्येवालुक् सिद्धः ॥

(प्रदीपः) अचीत्येवेति। अयं च द्वयोरपि साधारणः परिहारः ॥

(अलुग्वचनसाधकभाष्यम्)

अचीत्युच्यते। न चात्राजादिं पश्यामः ॥

(अलुग्वचनबाधकभाष्यम्)

प्रत्ययलक्षणेन ॥

(प्रत्ययलक्षणनिषेधस्मारणभाष्यम्)

ननु चोक्तं 'वर्णाश्रये नास्ति प्रत्ययलक्षणम्' इति॥

(समाधानभाष्यम्)

यदि वा कानि चिद्वर्णाश्रयाण्यपि प्रत्ययलक्षणेन भवन्ति तथेदमपि भविष्यति ॥

(प्रदीपः) यदि वेति। यथैवेत्यर्थः। यथातृणेडितीडागमः ॥ अयं भावः—यत्कार्यं वर्णरूपाश्रयं न प्रत्ययत्वाश्रयं न तत् प्रत्ययलक्षणेन भवति यथा गोहितमित्यादाववादयः। इमागमस्तु हलादिपित्सार्वधातुकाश्रयत्वात् प्रत्ययाश्रय इति प्रवर्तते। एव गोत्रेऽलुगचीत्यजादिप्रत्ययाश्रयत्वादलुक् प्रत्ययलक्षणेन प्रवर्तते ॥

(समाधानान्तरभाष्यम्)

अथ वाविशेषेणालुकमुक्त्वा 'हलि न' इति वक्ष्यामि ॥

(प्रदीपः) हलि नेति। यथा गर्गरूप्यमिति ॥

(आक्षेपभाष्यम्)

यद्येवमविशेषेणालुकमुक्त्वा 'हलि न' इत्युच्यते, बिदानामपत्यं बहवो माणवका बिदा अत्रापि प्राप्नोति ॥

(समाधानभाष्यम्)

अस्तु। पुनरस्य युवबहुत्वे वर्तमानस्य लुग् भविष्यति ॥

(प्रदीपः) पुनरस्येति। अपत्याधिकारादन्यत्र लौकिकस्यापत्यमात्रस्य गोत्रस्य ग्रहणमिति युवबहुत्वे यञञोश्चेति लुग् भविष्यतीत्यर्थः ॥

(आक्षेपभाष्यम्)

पुनरलुक्कस्मान्न भवति? ॥

(प्रदीपः) पुनरिति। लुक्छास्त्रवदलुक्छास्त्रस्यापि प्रवृत्तेरव्याघातादिति भावः ॥

(उद्द्योतः) लुक्शास्त्रवदलुक्शास्त्रस्यापीति। तस्याप्यपत्याधिकारबहिर्भूतत्वेन लौकिकगोत्रस्यैव ग्रहणादिति भावः ॥ ननु लक्ष्ये लक्षणस्येति न्यायेन पुनरप्रवृत्तिः। किंच यूनि लुगित्युत्तरत्रोक्तेर्गोत्रेऽलुगिति सूत्रे युवातिरिक्तापत्यस्यैव गोत्रग्रहणेन ग्रहणात् युवबहुत्वाश्रयलुकः कथमलुक्। अपि च यत्र गोत्रे वर्तमानस्य लुक् प्राप्तस्तद्व्यतिरिक्तप्राग्दीव्यतीयेऽर्थे योऽजादिस्तत्रैवेत्यर्थस्य शब्दमर्यादया लाभात्। न चास्यामवस्थायां प्रत्ययपर्सक्रान्तात्(?)कश्चिदिवक्षितोऽस्तीति चेन्न। अर्थभेदेन लक्ष्यभेदात्। गोत्रे विहितप्रत्ययस्येत्यर्थाश्रयणेनाप्यो युवातिरिक्तगोत्रे एव विहितस्य द्वितीयस्याप्यभावः। अत एव न तृतीयोपि ॥

(समाधानभाष्यम्)

समर्थानां प्रथमस्य गोत्रप्रत्ययान्तस्यालुगुच्यते। न चैतत्समर्थानां प्रथमं गोत्रप्रत्ययान्तम्। किं तर्हि?। द्वितीयमर्थमुपसंक्रान्तम् ॥ अवश्यं

चैतदेवं विज्ञेयम्। अत्रिभरद्वाजिका वसिष्ठकश्यपिका भृग्वङ्गिरसिका कुत्सकुशिकिका इत्येवमर्थम्॥

(प्रदीपः) समर्थानामिति। प्रतियोगं समर्थानां प्रथमादित्यस्यानुवृत्तिस्तत्रायमर्थः—समर्थानां प्रथमस्य गोत्रप्रत्ययस्यालुग् भवतीति प्राथमकल्पिके च प्रत्ययार्थे वर्तमानस्य प्राथम्यं यथा गार्गीया इति। अत्र युवप्रत्ययस्य लुकि कृते युवलक्षणं द्वितीयमर्थमुपसंक्रान्तोऽनन्तः शब्द इति प्राथम्याभावः॥ अत्रिभरद्वाजिकेति। अत्रेरपत्यानीतीतश्चानिञ इति ढक्। भरद्वाजस्यापत्यानीति विदाद्यञ्। तत उभाभ्यां युववहुत्वेत इञ्। तस्य ण्यक्षत्रियार्षेति लुक्। ढकोत्रिभृग्विति। अञो यञञोश्चेति भावः। ततोत्रिभरद्वाजानां मैथुनिकेति द्वन्द्वाद्वुन्निति वुन्। तस्याकादेशः। यदि द्वितीयमर्थमुपसंक्रान्तस्याप्यलुक् स्यात्तदा गोत्रे लुगचीति यथान्यासेपि अलुगयं प्रसज्येतेत्यर्थः॥ वसिष्ठकश्यपिकेति। वसिष्ठशब्दादृष्यण्। कश्यपादञ्। पूर्ववद्यून्यत इञ्। तस्य लुक्। ततोऽणञोर्लुक् वुन्॥ भृग्वङ्गिरसिकेति। ऋष्यण्। यून्यत इञ् तस्य लुक् अणो लुक् वुन्॥ कुत्सकुशिकिकेति। कुत्सादृष्यण्। कुशिकादञ्। अन्यत् पूर्ववत्॥

(उद्योतः) समर्थानां प्रथमस्येति। अत्र समर्थग्रहणानुवृत्तिप्रदर्शनस्योत्तरत्र तस्यानुवृत्तिसूचनमेव फलम्। प्रकृतोपयोगि तु प्रथमादित्येव। तस्य वाऽनुवृत्तस्यार्थवशाद्विभक्तिविपरिणाम इति भावः॥ अवश्यं चैतदित्यस्यार्थमाह—यथा न्यासेऽपीति॥ ततोऽणञोरिति। अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यश्चेत्यनेनाणः, यञञोश्चेत्यञ इत्यर्थः॥

(१६३५ समाधानवार्तिकम् ९)

॥ * ॥ गर्गभार्गविकाग्रहणं वा नियमार्थम्॥ * ॥

(भाष्यम्) गर्गभार्गविकाग्रहणं वा क्रियते तन्नियमार्थं भविष्यति—एतस्यैव द्वितीयमर्थमुपसंक्रान्तस्यालुग्भवति नान्यस्येति॥

(प्रदीपः) गर्गभार्गविकेति। गर्गशब्दाद्यञ्। तस्य लुक्। भृगुशब्दादृष्यण्। तदन्ताद्यून्यत इञ्। तस्य लुक्। गर्गभृगूणां मैथुनिकेति वुन्। अत्रात्रिभृग्विति लुक् प्राप्तो गोपवनादिपाठेन प्रतिषिध्यते। यदि च द्वितीयमर्थमुपसंक्रान्तस्याप्यलुक् स्याद गोपवनादिषु न पठ्येत, पठितस्तु यथोक्तार्थज्ञापनायेत्यर्थः॥

(उद्योतः) ज्ञापनायेति। प्रथमादित्येतत्संबन्धज्ञापनायेत्यर्थः॥ भाष्ये—नियमार्थमित्यस्य तत्संबन्धबोधनपूर्वकं नियमार्थमित्यर्थः॥ पूर्वं व्याख्यानात् तत्संबन्धः। इदानीं तु तत्रैवार्थे ज्ञापकमुक्तमिति भेदः॥

(दूषणपरिहारभाष्यम्)

यदप्युच्यते—*एकवचनद्विवचनान्तस्य प्रवृत्तौ बहुषु लोपो यूनि वक्तव्य* इति॥ मा भूदेवम्—अत्र्यो बहुषु यञ्यो बहुष्विति। अञन्तं यद्बहुषु यञन्तं यद् बहुष्वित्येवं भविष्यति॥

(प्रदीपः) अर्थनिर्देशवादी परिहारमाह—यदपीति॥

(उद्योतः) भाष्ये—अञन्तं यद् बहुष्विति। बहुष्वित्यस्याव्याप्त्यतिव्याप्तिवारकतया सारवत्त्वलाभेन तदन्तविशेषणमिति भावः॥

(आक्षेपस्मारणभाष्यम्)

ननु चोक्तम्—नैवं शक्यम्। इह हि दोषः स्यात्—काश्यपप्रतिकृतयः काश्यपाः—इति॥

(परिहारभाष्यम्)

नैष दोषः। लौकिकस्य तत्र गोत्रस्य ग्रहणम्। न चैतल्लौकिकं गोत्रम्॥

(प्रदीपः) लौकिकस्येति। अपत्यस्येत्यर्थः। प्रतिकृतिबहुत्वेऽयमञन्तो वर्तते न त्वपत्यबहुत्व इत्यर्थः॥ न चैतदिति। यद्यपि शास्त्रीयमपि न भवति तथापि स्थितपक्षाश्रयः परिहारो वक्तव्य इत्येवमुक्तम्॥

(दोषसाम्यभाष्यम्)

यस्य बहुवचने परतो लुक्। समासबहुत्वे तेन नेति प्रतिषेधो वक्तव्यः। तेनैव चेत्कृतं बहुत्वमिति वा वक्तव्यम्॥ यस्य प्रत्ययार्थबहुत्वे लुक् तेनाक्रियामिति वक्तव्यम्॥

(प्रदीपः) इदानीं पक्षद्वये दोषपरिगणनमाह—यस्येति॥

(समाधानभाष्यम्)

यस्य बहुवचने परतो लुक् तस्यायमधिको दोषः। अत्रय इति उदात्तनिवृत्तिस्वरः प्राप्नोति। तस्मात्प्रत्ययार्थबहुत्वे लुगित्येष पक्षो ज्यायान्॥

(प्रदीपः) तस्मादिति। अर्थपक्षे लुकोपरनिमित्तत्वादत्रय इत्युदात्तनिवृत्तिस्वराप्रसङ्गः। अक्रियामित्येतत्तु कृतमेव॥

(उद्योतः) तस्यायमधिको दोष इति। युगपदधिकरणवचनताया दूषितत्वाद् द्वन्द्वेऽबहुषु लुग्वचनमिति दोषोऽस्त्येवेति तस्याप्युपलक्षणमिदम्। अर्थपरत्वे तु युगपदधिकरणतां विनाऽपि तद्दोषोद्धार उक्तः॥

(आक्षेपभाष्यम्)

अथेह कथं भवितव्यं गार्गी च वात्स्यश्च वाज्यश्चेति॥

(प्रदीपः) गार्गी चेति । एकैकं शब्दरूपं स्त्रीपुंसात्मकसमुदायाभिधायि तत्र पर्युदासे सर्वेषां लुका भाव्यम् । प्रसज्यप्रतिषेधे तु न भाव्यमिति संदेहात् प्रश्नः ॥

(उद्द्योतः) एकैकमिति । द्वन्द्वरूपसमुदायस्य स्त्रीपुंसात्मकसमुदाये शक्तौ समुदायस्य प्रत्येकानतिरेकेणैकैकस्य तदभिधायकत्वमिति भावः । यद्वा समुदायाभिधायीत्यस्य समुदायगतबहुत्वाश्रयाभिधायीत्यर्थः ॥

(आक्षेपाशयभाष्यम्)

यदि तावदस्त्री विधिनाश्रीयते अस्त्यत्रास्त्रीति कृत्वा भवितव्यं लुका । अथ स्त्री प्रतिषेधेनाश्रीयते अस्त्यत्र स्त्रीति कृत्वा भवितव्यं प्रतिषेधेन ॥ किं पुनरर्थसत्तत्त्वम् ? ॥

(उद्द्योतः) भाष्ये—अर्थसत्तत्त्वमिति । तत्त्वसत्तत्त्वशब्दौ पर्यायौ ॥

(समाधानभाष्यम्)

देवा ज्ञातुमर्हन्ति ॥

(प्रदीपः) देवा इति । दिव्यदृशः देवा इति पण्डिता इत्यर्थः । तत्र पर्युदासस्यैकवाक्यतया लाघवात् न्याय्यत्वमिति केचिदाहुः । अन्ये तु ब्रुवते गार्गीशब्देन स्त्रीत्वयुक्तानामर्थानामभिधानाद् यञो लुका न भाव्यम् अन्येषां तु भाव्यमिति ॥

(उद्द्योतः) पण्डितशेयप्रकारं दर्शयति—तत्रेति। अन्येषां मतं तु न युक्तं न हि गार्गीशब्देन स्त्रीत्वयुक्ता बहवो गार्ग्य उच्यन्ते । गार्गी चेत्येकवचनान्तेन भाष्ये विग्रहकरणात् समासे संख्याविशेषानवगमाच्च युगपदधिकरणवचनतापक्षेऽपि वात्स्यादयः स्त्रीत्वयुक्ता नोच्यन्ते अनुभवविरोधादित्याहुः । पर्युदासप्रतिषेधयोरुभयोरपि गार्गीशब्दे लुगभावो अन्ययोर्लुगित्यर्थत्वेनार्थान्तरानुपसंक्रान्त उद्भूतावयवभेदे समूहे गार्ग्यां उपसंक्रान्तत्वेनार्थान्तरानुपसंक्रान्तास्त्रियोऽभावादिति परे ॥

(आक्षेपभाष्यम्)

अथ यो लोप्यलोपिनां समासस्तत्र कथं भवितव्यम् ? ॥

(प्रदीपः) अथेति । लोपभाजामन्येषां च यः समास इत्यर्थः । यदा लोपभाग् युगपदर्थानामभिधानाद् बह्वर्थस्तदा तदाश्रयेण किं तस्य लुक् क्रियताम् ॥ अथ तेनैवेति वचनादलोपिसन्निधिकृतं बहुत्वमिति मा कारि लुगिति प्रश्नः ॥

(उद्द्योतः) बह्वर्थ इति । बहुत्वाश्रयार्थमित्यर्थः ॥ अथ तेनैवेति वचनादिति । प्रत्ययग्रहणपक्षे तेनैवेति वचनान्न भवति लुक् अर्थग्रहणपक्षे तदभावात् प्राप्नोति तथा च द्वितीयपक्षे एतदर्थमेव तेनैवेति किं कर्त्तव्यमिति प्रश्नाशय इति भावः ॥

(समाधानभाष्यम्)

उभयं हि दृश्यते—"शरद्वच्छुनकदर्भाद् भृगुवत्साग्रायणेषु" । "नोदात्तस्वरितोदयमगार्ग्यकाश्यपगालवानाम्" इति ॥ तद्राजस्य ॥ ६२ ॥

(प्रदीपः) उभयं हीति । ज्ञापकद्वयसद्भावादुभयं भवतीति भावः ॥ भृगुवत्साग्रायणेष्विति । अत्र द्वौ लोपिनौ तृतीयस्तु नडादिफगन्तो न लोपी द्वयोश्च लुक् कृतः । अगार्ग्यकाश्यपगालवानामिति । द्वौ लोपिनौ गालवस्तु ऋष्यणन्तो न लोपी । न च लोपिनोर्लुक् कृतस्तदेवं ज्ञापकद्वयसद्भावात् प्रयोगद्वयोपपत्तिः ॥ ६२ ॥

(उद्द्योतः) ज्ञापकद्वयेति । एवंच तेनैवेति न कार्यमिति भावः । तेनैवेति कुर्वताऽपि भृगुवत्साग्रायणेष्विति प्रयोगनिर्वाहाय ज्ञापकस्यावश्याश्रयणीयत्वात् । एवं च गार्ग्यश्च चैत्रश्चेत्यादौ द्वन्द्वे यथाप्रयोगं लुगलुकोर्व्यवस्था बोध्या ॥ ६२ ॥

(३६७ लुक्सूत्रम् ॥ २ । ४ । २ आ. २)

५९५ यञञोश्च ॥ २ । ४ । ६४ ॥

(षष्ठीतत्पुरुषेद्व्येकयोर्विकल्पाधिकरणम्)

(१६३६ वार्तिकम् ॥ १ ॥)

॥ * ॥ यञादीनामेकद्वयोर्वा तत्पुरुषे षष्ठ्या उपसंख्यानम् ॥ * ॥

यञादीनामेकद्वयोर्वा तत्पुरुषे षष्ठ्या उपसंख्यानं कर्तव्यम् । गार्ग्यस्य कुलं गार्ग्यकुलं गर्गकुलं वा । गार्ग्ययोः कुलं गार्ग्यकुलं गर्गकुलं वा । वैदस्य कुलं वैदकुलं विदकुलं वा । वैदयोः कुलं वैदकुलं बिदकुलं वा ॥ यञादीनामिति किमर्थम् ? । आङ्गस्य कुलम् आङ्गकुलम् । आङ्गयोः कुलमाङ्गकुलम् ॥ एकद्वयोरिति किमर्थम् ? । गर्गाणां कुलं गर्गकुलम् ॥ तत्पुरुष इति किमर्थम् ? । गार्ग्यस्य समीपमुपगार्ग्यम् ॥ षष्ठ्या इति किमर्थम् ? । शोभनगार्ग्यः । परमगार्ग्यः ॥ यञञो ॥ ६४ ॥

(प्रदीपः) यञ ॥ ६४ ॥ यञादीनामिति । इतः प्रभृति ये प्रत्यया बहुषु लुग्भाजस्ते यञादय आदिशब्दस्य व्यवस्थावाचित्वात् ॥ ६४ ॥

(उद्द्योतः) यञञोश्च ॥ ६४ ॥ इतः प्रभृतीति । अतः पूर्वविषये आङ्गकुलमित्येवेति भावः ॥ ६४ ॥

(३६८ लुक्सूत्रम् ॥ २ । ४ । २ आ. ३)

५९७ बह्वच इञः प्राच्यभरतेषु ॥ २।४।६६ ॥

(प्राच्यभरतानां समुच्चयाधिकरणम्)

(आक्षेपभाष्यम्)

किमयं समुच्चयः प्राक्षु च भरतेषु चेति। आहोस्विद्भरतविशेषणं प्राग्ग्रहणं प्राञ्चो ये भरता इति॥

(प्रदीपः) बह्वचः ॥६६॥ द्वन्द्वतत्पुरुषयोर्द्वयोरपि संभवाद्दोषदर्शनाच्च प्रश्नः—किमयमिति । गोबलीवर्दवत्सामान्यविशेषवाचिनोरपि द्वन्द्वसंभवः ॥

(उद्योतः) बह्वचः ॥ ६६ ॥ सामान्यविशेषयोर्द्वन्द्वासंभवादाह—गोबलीति । इदमेव तयोरपि समासज्ञापकमिति भावः । वस्तुतो गोबलीवर्दमित्यादौ सामान्यविशेषभाव एव नेत्येकशेषप्रकरणान्ते भाष्ये उक्तत्वेनात्र सौत्रत्वाद् द्वन्द्वः ॥ सामान्यविशेषवाचिनोर्नैव द्वन्द्वः सामान्यविशेषवाचिनोर्द्वन्द्वो नेति वक्तव्यमिति तत्रैव भाष्योक्तेरिति बोध्यम् ॥ ६६ ॥

(जिज्ञासाभाष्यम्)

किं चातः ? ॥

(विशेषप्रदर्शनभाष्यम्)

यदि समुच्चयः। भरतग्रहणमनर्थकम् । न ह्यन्यत्र भरताः सन्ति ॥

अथ प्राग्ग्रहणं भरतविशेषणम् । प्राग्ग्रहणमनर्थकम् । नह्यप्राञ्चो भरताः सन्ति ॥

(प्रथमपक्षाभ्युपगमभाष्यम्)

ए.ं तर्हि समुच्चयः॥

(दोषस्मरणभाष्यम्)

ननु चोक्तम्—भरतग्रहणमनर्थकं नह्यन्यत्र भरताः सन्तीति ॥

(समाधानभाष्यम्)

नानर्थकम् । ज्ञापकार्थम् ॥ किं ज्ञाप्यते ? । एतज्ज्ञापयत्याचार्यः—'अन्यत्र प्राग्ग्रहणे भरतग्रहणं न भवति' इति ॥ किमेतस्य ज्ञापने प्रयोजनम् ? । "इञः प्राचाम्" भरतग्रहणं न भवति । औद्दालकिः पिता । औद्दालकायनः पुत्र इति ॥ बह्वचः ॥ ६६ ॥

(प्रदीपः) औद्दालकिरिति । उद्दालको नाम भरतकुलोत्पन्नः ॥ ६६ ॥

(३६९ लुक्प्रतिषेधसूत्रम् ॥ २ ।४ । २ आ. ४ सू.)

५९८ न गोपवनादिभ्यः ॥ २।४।६७ ॥

(१६३७ वार्तिकम् ॥ १)

॥ * ॥ गोपवनादिप्रतिषेधः प्राग्घरितादिभ्यः ॥ * ॥

गोपवनादिप्रतिषेधः प्राग्घरितादिभ्यो द्रष्टव्यः । हारितः हारितौ । बहुषु—हरिताः ॥ न गोपव॥६७

(प्रदीपः) न गोप ॥ ६७ ॥ विदाद्यन्तर्गणो गोपवनादिः । न च तत्समाप्तये गणे वृत्करणं पठितमिति आगणान्ताद् ग्रहणं प्राप्नोतीत्याह—गोपवनादिप्रतिषेध इति ॥ ६७ ॥

(३७० विकल्पसूत्रम् ॥ २ । ४ । २ आ. ५)

६०० उपकादिभ्योन्यतरस्यामद्वन्द्वे ॥ २।४।६९ ॥

(अद्वन्द्वग्रहणप्रयोजनाधिकरणम्)

(आक्षेपभाष्यम्)

किमर्थमद्वन्द्व इत्युच्यते ? ॥

(प्रदीपः) उपका ॥ ६९ ॥ द्वन्द्वेपि लुग्विकल्पस्येष्टत्वात् प्रश्नः—किमर्थमिति ॥

(समाधानभाष्यम्)

द्वन्द्वे मा भूदिति ॥

(समाधानबाधकभाष्यम्)

नैतदस्ति प्रयोजनम् । इष्यते द्वन्द्वे भ्राष्ट्रककपिष्ठलाः । भ्राष्ट्रकिकापिष्ठलय इति ॥

(प्रदीपः) भ्राष्ट्रकिकापिष्ठलय इति । अस्मादेवोदाहरणात्तिककितवादिष्वस्य पाठोनार्ष इति लक्ष्यते ॥

(उद्योतः) उपकादि ॥ ६९ ॥ पाठोऽनार्ष इति । वृत्तिकारोक्त इत्यर्थः ॥

(समाधानभाष्यम्)

अत उत्तरं पठति—

(१६३८ समाधानवार्तिकम् ॥ १ ॥)

॥ * ॥ अद्वन्द्व इति द्वन्द्वाधिकारनिवृत्त्यर्थम् ॥ * ॥

अद्वन्द्व इत्युच्यते द्वन्द्वाधिकारनिवृत्त्यर्थम् । द्वन्द्वाधिकारो निवर्त्यते तस्मिन्निवृत्ते अविशेषेण द्वन्द्वे चाद्वन्द्वे च भविष्यति ॥ उपकादिभ्यो ॥ ६९ ॥

(प्रदीपः) **द्वन्द्वाधिकारनिवृत्त्यर्थमिति** । अधिकारशब्देनात्र शास्त्रीयोधिकारः स्वरितत्वनिमित्तो न गृह्यते नहि पूर्वसूत्रोपात्तो द्वन्द्वशब्द आसक्तस्वरितः । किं तर्हि; लौकिकोधिकारोपेक्षालक्षणो निविवर्तयिषितः । द्वन्द्वशब्देन तद्विषयोधिकारोभिधीयते तस्य नञा निषेधो द्योत्यते ॥ तेनायमर्थो द्वन्द्व इह नापेक्ष्यते । तदनपेक्षायां सामान्येन द्वन्द्वे चाद्वन्द्वे च लुग्विकल्पसिद्धिः ॥ ६९ ॥

(उद्द्योतः) **आसक्तस्वरित इति** । फलाभावादिति भावः । स्वरितत्वासङ्गभावस्यैवान्वाख्यानं वार्त्तिकमित्यन्ये ॥ ६९ ॥

(३७१ प्रकृत्योरादेशसूत्रम् ॥ २ । ४ । २ आ. ६ सू.)

६०१ आगस्त्यकौण्डिन्ययोरगस्तिकुण्डिनच् ॥ २।४।७० ॥

(प्रकृत्यादेशत्वनिर्णयाधिकरणम्)

(१६३९ वार्तिकम् ॥ १ ॥)

॥ * ॥ आगस्त्यकौण्डिन्ययोः प्रकृतिनिपातनम् ॥ * ॥

(भाष्यम्) आगस्त्यकौण्डिन्ययोः प्रकृतिनिपापातनं कर्तव्यम् । अगस्ति—कुण्डिनजित्येतौ प्रकृत्यादेशौ भवत इति वक्तव्यम् ॥

किं प्रयोजनम् ? ॥

(१६४० वार्तिकद्वितीयखण्डम् ॥ २ ॥)

॥ * ॥ लुक्प्रतिषेधे वृद्ध्यर्थम् ॥ * ॥

(भाष्यम्) लुक्प्रतिषेधे वृद्धिर्यथा स्यात् ॥

(१६४१ वार्तिकतृतीयखण्डम् ॥ ३ ॥)

॥ * ॥ प्रत्ययान्तनिपातने हि वृद्ध्यभावः ॥ * ॥

(भाष्यम्) प्रत्ययान्तनिपातने हि सति वृद्ध्यभावः स्यात् । आगस्तीयाः कौण्डिना इति ॥

(प्रदीपः) **आगस्त्य ॥ ७० ॥** प्रकृतिप्रत्ययसमुदायस्य षष्ठीनिर्दिष्टत्वादादेशप्रसङ्गस्ततश्चागस्तीनां छात्रा इत्यत्रादेशे कृतेऽवृद्धत्वाच् छो न स्यादित्याह—**प्रकृतिनिपातनमिति** । प्रकृतेरेवादेशौ निपातनीयावित्यर्थः ॥ **लुक्प्रतिषेध इति** । **गोत्रेऽलुगचीति** लुकि प्रतिषिद्धे तत्संनियोगशिष्टस्यादेशस्याप्यभाव इत्यागस्त्यशब्दाच्छः सिध्यति ॥ **प्रत्ययान्तनिपातने हीति** । यदि प्रत्ययान्तस्यादेशः क्रियेतेत्यर्थः ॥ **कौण्डिना इति** । **कण्वादिभ्यो गोत्र** इत्यण् । अस्य विशेषाभावप्रदर्शनायोपन्यासः ॥

(उद्द्योतः) आगस्त्यकौण्डिन्य ॥ ७० ॥ प्रकृतिनिपातनशब्दस्य विवक्षितमर्थमाह—**प्रकृतेरेवेति** । अर्थादेव प्रत्ययस्य लुगिति बोध्यमिति भावः ॥ भाष्ये—**वृद्ध्यभावः स्यादिति** । एवं च च्छो न स्यादिति भावः ॥ पूर्वं फलाभावाद्वृद्धसंज्ञाभावेन स्थानिवद्भावेन न तल्लाभ इति बोध्यम् ॥ **अस्य विशेषेति** । यद्यपि कौण्डिना इति सिध्यति । तथाप्यागस्तीया इति न सिध्यतीति व्याख्येयमिति भावः ॥

(आक्षेपभाष्यम्)

यदि प्रकृतिनिपातनं क्रियते । केनेदानीं प्रत्ययस्य लोपो भविष्यति ? ॥

(१६४२ वार्तिकम् ॥ ४ ॥)

॥ * ॥ अधिकारात्प्रत्ययलोपः ॥ * ॥

(भाष्यम्) अधिकारात्प्रत्ययलोपो भविष्यति ॥

(प्रदीपः) **अधिकारादिति** । लुग्ग्रहणमिहानुवर्तते । तत्र प्रकृतेरादेशः, प्रत्ययस्य तु लुगित्यर्थः संपद्यते ॥

(आक्षेपभाष्यम्)

तर्त्तर्हि प्रकृतिनिपातनं कर्तव्यम् ? ॥

(समाधानभाष्यम्)

न कर्तव्यम् ॥

(१६४३ वार्तिकम् ॥ ५ ॥)

[॥ * ॥ योगविभागात् सिद्धम् ॥ * ॥]

(भाष्यम्) योगविभागः करिष्यते—["आगस्त्यकौण्डिन्ययोः"] आगस्त्यकौण्डिन्ययोर्बहुषु लुग्भवति । ततः ["अगस्ति कुण्डिनच्"] अगस्तिकुण्डिनजित्येतौ च प्रकृत्यादेशौ भविष्यतः आगस्त्यकौण्डिन्ययोरिति ॥

(प्रदीपः) **बहुषु लुग् भवतीति** । बहुषु वर्तमानयोर्यः प्रत्ययस्तस्येत्यर्थः ॥ **प्रकृत्यादेशाविति** । सामर्थ्यलभ्योयमर्थः । प्रत्यये हि लुप्ते प्रकृतिरेवावशिष्यते ॥

(उद्द्योतः) ननु प्रत्ययवाचकपदाभावेन बहुष्वित्यस्य प्रत्ययान्तसमुदाये एवान्वयेन तस्यैव लुक् स्यादत आह—**बहुष्विति ॥ यः प्रत्यय इति**। लुगाक्षिप्तोऽयम्, प्रत्ययादर्शनस्यैव लुक्त्वादिति बोध्यम्॥

(प्रत्याक्षेपभाष्यम्)

एवमपि प्रत्ययान्तयोरेव प्राप्नोति । प्रत्ययान्ताद्धि भवान् षष्ठीमुच्चारयति—"आगस्त्यकौण्डिन्ययोः" इति॥

(प्रदीपः) **एवमपीति**। षष्ठीनिर्दिष्टस्यादेशविधानादिति भावः। ततश्च लुक आदेशयोश्च पर्यायप्रसङ्गः॥

(उद्द्योतः) **षष्ठीनिर्दिष्टस्येति**। स्थानषष्ठी सामर्थ्यस्य प्रतिबन्धिकेति भावः॥

(समाधानभाष्यम्)

नैष दोषः। यथापरिभाषितं प्रत्ययस्य लुक्श्लुलुपो भवन्तीति प्रत्ययस्यैव भविष्यति । अवशिष्टस्यादेशौ भविष्यतः॥ आगस्त्य॥७०॥

(प्रदीपः) **यथापरिभाषितमिति** । तत्र स्थानिभेदात् पर्यायाभावः॥७०॥

(उद्द्योतः) **तत्रेति**। एतदर्थमेव तत्र प्रत्ययग्रहणं कृतम्॥ यद्वा गोत्रे इत्यनुवर्त्य गोत्रे कृतस्य लुगित्यर्थान्न दोषः॥ **पर्यायाभाव इति**। विकल्पस्याष्टदोषदुष्टत्वादित्यपि बोध्यम्॥७०॥

(इति तद्धितलुक्प्रकरणम्)

(अथ धातुप्रत्ययलुक्प्रकरणम्)

(३७२ यङ्लुक्सूत्रम्॥२।४।२ आ. ७ सू.)

६०५ यङोचि च ॥ २।४।७४ ॥

(उद्द्योतः) यङोऽचि च॥७४॥ यङा साहचर्याद्च् प्रत्यय एवात्र गृह्यते॥

(१६४४ वार्तिकम्॥१॥)

॥ * ॥ ऋतोचि ॥ * ॥

(भाष्यम्) **ऋतः अचीति वक्तव्यम् । इह मा भूत्—सनीस्रसो दनीध्वस इति॥**

(प्रदीपः) **यङोचि॥७४॥ सनीस्रस इति**। यद्यत्र लुक् स्यात्तदा **न लुमताङ्गस्येति** प्रत्ययलक्षणप्रतिषेधान्नलोपो न स्यात्। **अतो लोपः यस्य हल** इति लोपे तु प्रत्ययलक्षणं भवत्येव॥७४॥

(उद्द्योतः) **ऋतोऽचि**। ऋतः परस्य यङोऽचि लुगित्यर्थः॥ **यद्यत्रेति। न धात्विति** सूत्रस्यप्रत्याख्यानप्रकारस्तु लक्ष्यविशेषविषय एवेति निरूपितं तत्रैव भाष्ये॥

(आक्षेपभाष्यम्)

अथ ऊत इत्युच्यते । इह कस्मान्न भवति—योयूयः। रोरूयः?॥

(समाधानभाष्यम्)

विहितविशेषणमूकारग्रहणम् । ऊकारान्ताद्यो विहित इति॥

(आक्षेपभाष्यम्)

तत्तर्हि वक्तव्यम्?॥

(समाधानभाष्यम्)

न वक्तव्यम्। इष्टमेवैतत्संगृहीतम्—सनीस्रंसो दनीध्वंस इत्येव भवितव्यम्॥ यङो०॥७४॥

(उद्द्योतः) **इत्येव भवितव्यमिति**। योयूयो रोरूय इत्यत्र बाहुलकाद्यङ्लुगभाव एवेत्यपरे॥७४॥

(३७३ सिज्लुक्सूत्रम्॥२।४।२ आ. ८)

६०८ गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु ॥ २।४।७७ ॥

(धातुविशेषनिर्णयाधिकरणम्)

(१६४५ वार्तिकम्॥१॥)

॥ * ॥ गापोर्ग्रहणे इण्पिबत्योर्ग्रहणम् ॥ * ॥

(भाष्यम्) **गापोर्ग्रहणे इण्पिबत्योर्ग्रहणं कर्तव्यम्। इणो यो गाशब्दः पिबतेर्यः पाशब्द इति वक्तव्यम्। इह मा भूत्—अगासीन्नटः, अपासीद्धनमिति॥**

(प्रदीपः) **गाति॥७७॥ पिबतेरिति**। पिबतेर्यः स्थानी दृष्टः पाशब्द इत्यर्थः। शिति च पिबादेशो विहित इति **पा** पान इत्यस्यैव भौवादिकस्य ग्रहणम्॥ **अगासीदिति। गै** शब्दे **पा** रक्षणे अनयोर्**यमरमनमातां सक् च** इति समागमः। सिचश्चेद्॥

(उद्द्योतः) **गातिस्था॥७७॥ इणो गा शब्द इति** भाष्ये इकोपीण्वद्भावात्तदादेशस्यापि सिद्धिरिति भावः॥ **यःस्थानीति**। स्थान्यादेशसम्बन्धे षष्ठीति भावः॥ ननु पातेरपि पिबादेशः किं नेत्यत आह—**शिति चेति**॥

(आक्षेपभाष्यम्)

तत्तर्हि वक्तव्यम्?॥

(समाधानभाष्यम्)

न वक्तव्यम्। इण्ग्रहणे तावद्वार्त्तम्—निर्देशादेव व्यक्तं 'लुग्विकरणस्य ग्रहणम्' इति॥

पाग्रहणे चापि वार्तत्तम्—उक्तमेत्तत्—'सर्वत्रैव पाग्रहणे अलुग्विकरणस्य ग्रहणम्' इति ॥ गातिस्था ॥ ७७ ॥

(प्रदीपः) निर्देशादिति । गातीत्यादादिकादेशानुकरणत्वाददादिलुका गातिशब्दः श्तिपा निर्दिष्टः ॥ सर्वत्रेति । घुमास्थागापेत्यादावपीत्यर्थः । तेन पायते इति पातेरीत्वाभावः । शोषणार्थस्य तु पायतेर्लाक्षणिकत्वात्पारूपस्य ग्रहणाभावः ॥ ७७ ॥

(उद्द्योतः) अदादिलुकेति । श्तिपः कर्त्रर्थकत्वाभावाद्विकरणो न न्यायप्राप्त इतिवादिनां मतेपि तस्य गैतिरिति स्यादित्याशयः । न च गैशब्दे इत्यस्य कृतात्वस्यानुकरणात् श्तिप्यपि एवमेव रूपेण निर्देशः संदिग्ध इति वाच्यम्, लाक्षणिकत्वेन तस्याननुकरणतयाऽस्मात् श्तिपि एवमेव रूपं तस्यैव ग्रहणाच्च ॥ अन्यथा 'गास्थाघु—' इत्येवमेव वदेदिति भावः । गाङ्स्तु नानुकरणं परस्मैपदपरत्वाभावात् ॥ गामादाग्रहणेष्वविशेष इति श्तिब्रहितगादेशविषयमिति बोध्यम् ॥ भाष्ये—ऽलुग्विकरणस्येति । लुग्विकरणालुग्विकरणयोरलुग्विकरणस्येत्यनयेत्यर्थः ॥ ७७ ॥

(३७४ सिज्लुक्सूत्रम् ॥ २ । ४ । २ आ. ९)

६१० तनादिभ्यस्तथासोः ॥ २।४।७९॥

(तप्रत्ययनिर्णयाधिकरणम्)

(१६४६ वार्तिकम् ॥ १ ॥)

॥ * ॥ तथासोरात्मनेपदवचनम् ॥ * ॥

(भाष्यम्) तथासोरात्मनेपदस्य ग्रहणं कर्तव्यम् । आत्मनेपदं यौ तथासाविति वक्तव्यम् ॥

(१६४७ वार्तिकम् ॥ २ ॥)

॥ * ॥ एकवचनग्रहणं वा ॥ * ॥

(भाष्यम्) अथ वा एकवचनं ये तथासी इति वक्तव्यम् ॥ तच्चावश्यमन्यतरत्कर्तव्यम् ॥

(१६४८ वार्तिकम् ॥ ३ ॥)

॥ * ॥ अवचने ह्यनिष्टप्रसङ्गः ॥ * ॥

(भाष्यम्) अनुच्यमाने ह्येतस्मिन्ननिष्टं प्रसज्येत—अतनिष्ट यूयम् असनिष्ट यूयमिति ॥

(उद्द्योतः) तनादिभ्यः ॥ ७९ ॥ अतनिष्टेति । मध्यमपुरुषबहुवचनम् ॥ ७९ ॥

(आक्षेपभाष्यम्)

तर्त्तार्ह वक्तव्यम् ? ॥

(समाधानभाष्यम्)

न वक्तव्यम् । यद्यपि तावदयं तशब्दो दृष्टापचारोस्त्यात्मनेपदम्, अस्ति च परस्मैपदम्, अस्त्येकवचनम्, अस्ति बहुवचनम् अयं तु खलु थास्शब्दोऽदृष्टापचार आत्मनेपदमेकवचनं च । तस्यास्य कोन्यः सहायो भवितुमर्हति अन्यदत आत्मनेपदादेकवचनाच्च । तद्यथा—'अस्य गोर्द्वितीयेनार्थ' इति गौरेवानीयते नाश्वो न गर्दभ इति ॥ तनादि ॥ ७९ ॥

(३७५ लुक्सूत्रम् ॥२।४।२ आ. १०)

६१२ आमः ॥ २।४।८१ ॥

(लुङ्लोटोर्लुक्साधनाधिकरणम्)

(१६४९ शेषवार्तिकम् ॥ १ ॥)

॥ * ॥ आमो लेर्लोपे लुङ्लोटोरुपसंख्यानम् ॥ * ॥

(भाष्यम्) आमः लेर्लोपे लुङ्लोटोरुपसंख्यानं कर्तव्यम् । तां वैजवापयो विदामक्रन् । अस्य भवन्तो विदांकुर्वन्तु ॥

(आक्षेपभाष्यम्)

तर्त्तार्ह वक्तव्यम् ? ॥

(समाधानभाष्यम्)

न वक्तव्यम् । लिग्रहणं निवर्तिष्यते ॥

(प्रदीपः) आमः ॥ ८१ ॥ लिग्रहणमिति । निपातनादप्यत्र लुक् सिध्यति । तत्त्वनपेक्ष्यायं परिहार उक्तः ॥

(उद्द्योतः) आमः ॥ ८१ ॥ यद्यपि पूर्वसूत्रे लेरिति च्लेर्ग्रहणं तथाप्यत्र योग्यतावशाल्लिट एव ग्रहणमिति वार्तिकम् ॥ निपातनादिति । विदांकुर्वन्त्वित्यन्यतरस्यामिति अभ्युत्सादयामित्यादिनिपातनादित्यर्थः ॥ तत्त्विति । लेरित्यननुवृत्त्या सर्वेष्टसिद्धौ तदनुवृत्तिमभ्युपगम्य लुङ्लोटोर्निपातनाश्रयणमयुक्तमित्यँनपेक्षाबीजम् ॥

(आक्षेपभाष्यम्)

यदि निवर्तते । प्रत्ययमात्रस्य लुक् प्राप्नोति ॥

(प्रदीपः) प्रत्ययमात्रस्येति । तरबादेरपीत्यर्थः ॥

(उद्द्योतः) तरबादेरिति । लावस्थायामेव लुकः प्राप्त्या कृदन्तत्वात्प्रातिपदिकत्वेन तरबुत्पत्स्यत इत्याशयः । आदिना तमप् तदन्तादुत्पन्न आम् च ग्राह्यः ॥

(समाधानभाष्यम्)

इष्यत एव प्रत्ययमात्रस्य ॥ आतश्चेष्यते । एवं ह्याह "कृञ्चानुप्रयुज्यते लिटि" इति । यदि च प्रत्ययमात्रस्य लुग् भवति तत एतदुपपन्नं भवति ॥

(प्रदीपः) एवं ह्याहेति। व्यवहितविपर्यस्तप्रयोगनिवृत्त्यर्थमेव तद्वचनमित्यर्थः। आमन्तस्यानभिव्यक्तपदार्थत्वाच्च स्वाभाविक्येवानुत्पत्तिस्तरबादेर्लुग्द्वारेणान्वाख्यायत इति भावः॥

(उद्द्योतः) व्यवहितेति। तरबादौ सति व्यवहितत्वं स्यादिति भावः॥ नन्वनभिव्यक्तपदार्थकत्वेनातिशयाद्ययोगात्तरबाद्यनुत्पत्तौ कथं लुगित्यत आह—आमन्तस्येति। प्रत्ययमात्रस्य लुक्फलप्रदर्शनमिष्यत एवानुत्पत्तिरिति भाष्याक्षरार्थ इति भावः॥

(आम्ग्रहणनिर्णयाधिकरणम्)

(१६५० आक्षेपवार्तिकम् ॥ २ ॥)

॥ * ॥ आमन्तेभ्यो णलः प्रतिषेधः ॥ * ॥

(भाष्यम्) आमन्तेभ्यो णलः प्रतिषेधो वक्तव्यः। शशाम तताम। वृद्धौ कृतायम् "आमः" इति लुक् प्राप्नोति॥

(१६५१ समाधानवार्तिकम् ॥ ३ ॥)

॥ * ॥ आमन्तेभ्योऽर्थवद्ग्रहणाण्णलोऽप्रतिषेधः ॥ * ॥

(भाष्यम्) आमन्तेभ्योऽर्थवद्ग्रहणाण्णलः। अप्रतिषेधः। अनर्थकः प्रतिषेधोऽप्रतिषेधः॥ लुक् कस्मान्न भवति—शशाम ततामेति?। अर्थवद्ग्रहणात्। अर्थवत आम्शब्दस्य ग्रहणम्। न चैषोऽर्थवान्॥

(प्रदीपः) अर्थवत इति। आम् प्रत्ययोऽनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्तीत्यर्थवान्॥

(उद्द्योतः) नन्वर्थवानामसंभवीत्यत आह—आम्प्रत्यय इति॥

(१६५२ समाधानबाधकवार्तिकम् ॥ ४ ॥)

॥ * ॥ आमन्तेभ्योऽर्थवद्ग्रहणाण्णलोऽप्रतिषेध इति चेदमः प्रतिषेधः ॥ * ॥

(भाष्यम्) आमन्तेभ्योऽर्थवद्ग्रहणाण्णलोऽप्रतिषेध इति चेत् अमधातोः प्रतिषेधो वक्तव्यः। आम॥

(प्रदीपः) आम इति। अमगत्यादिष्वित्यस्य णलि वृद्धौ द्विर्वचन एकादेशे च यद्रूपमामिति तस्यार्थवत्त्वाण्णलो लुक्प्रसङ्गः॥

(समाधानसाधकभाष्यम्)

उक्तं वा॥ किमुक्तम्?। "सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य" इति॥

(उद्द्योतः) भाष्ये—सन्निपातेति। लक्षणप्रतिपदोक्तपरिभाषया प्रत्ययाप्रत्यययोरिति परिभाषया च सुसाध्यमेतत्॥

(लुकआदेशापवादत्वाधिकरणम्)

(आक्षेपभाष्यम्)

किं पुनर्लुगादेशापवादः, आहोस्वित्-कृतेष्वादेशेषु भवति॥

(प्रदीपः) किं पुनरिति। यदा 'विशेषविधिः सामान्यविधिबाधक' इति न्याय आश्रीयते तदा लकारान्तरेषु साकाशास्तिबादयो विशेषविहितेन लुका बाध्यन्त इत्यादेशापवादो लुक् संपद्यते। अथ त्वविरोधादस्ति च संभवो यदुभयं स्यादित्याश्रीयते तदा कृतेष्वादेशेषु लुका भाव्यमिति संदेहात् प्रश्नः॥

(उद्द्योतः) तदा कृतेष्विति। विरोधाभावादेवान्तरङ्गत्वात्पूर्वं लुगित्यपि न वाच्यमिति भावः। विहितानां नियम इतिपक्षाश्रयणाद्वोभयोस्तुल्यत्वम्॥

(१६५३ समाधानवार्तिकम् ॥ ५ ॥)

॥ * ॥ लुगादेशापवादः ॥ * ॥

(भाष्यम्) लुग् आदेशानामपवादः॥

(प्रदीपः) लुगिति। सत्यपि संभवे बाधनं तक्रदानेनेव दधिदानस्येति भावः॥

(उद्द्योतः) सत्यपीति। न चानुत्पत्तिकाले परत्वात्ततः प्रागेव वादेशाः किं न भवन्तीति वाच्यम्। अपवादविषये उत्सर्गाप्रवृत्तेः। प्रकल्प्य वापवादविषयमिति न्यायात्॥

(१६५४ समाधानबाधकवार्तिकम् ॥ ६ ॥)

॥ * ॥ तिङ्कृताभावस्तु ॥ * ॥

(भाष्यम्) तिङ्कृतस्य तु अभावः॥ कस्य?। पदत्वस्य॥

(प्रदीपः) कस्येति। निघातादेस्तिङ्कार्यस्यानिष्टत्वात् प्रश्नः॥

(१६५५ समाधानसाधकवार्तिकम् ॥ ७ ॥)

॥ * ॥ सुबन्तत्वात्सिद्धम् ॥ * ॥

(भाष्यम्) सुबन्तं पदम्' इति पदसंज्ञा भविष्यति॥

(आक्षेपभाष्यम्)

कथं स्वाद्युत्पत्तिः?॥

(प्रदीपः) कथमिति। आमः प्रत्ययत्वाद् 'अप्रत्यय' इति प्रातिपदिकसंज्ञानिषेधात् प्रश्नः॥

(१६५६ समाधानवार्तिकम् ॥ ८ ॥)

॥ * ॥ लकारस्य कृत्त्वात् प्रातिपदिकत्वं तदाश्रयं प्रत्ययविधानम् ॥ * ॥

(भाष्यम्) लकारः कृत्, 'कृत्प्रातिपदिकम्' इति प्रातिपदिकसंज्ञा, तदाश्रयं प्रत्ययविधानम्, प्रातिपदिकाश्रयत्वात्स्वाद्युत्पत्तिर्भविष्यति॥

(प्रदीपः) लकारस्येति। अतिङिति कृत्संज्ञाप्रतिषेधस्तिङ्भाविनो लकारस्य। अयं तु तिङ्भावी न भवतीति भावः॥

(उद्योतः) ननु अतिङ्ङिन्तेन तिङ्सानित्वयोग्यस्य लस्य कृत्संज्ञा प्रतिषिध्यत इति कथं लिटः कृत्वमत आह—तिङ्भाविन इति ॥

(समाधानबाधकभाष्यम्)

[यद्येवं] सुपः श्रवणं प्राप्नोति ॥

(प्रदीपः) सुपः श्रवणमिति । यद्यप्येकवचनस्य हल्ङ्यादिलोपोऽस्ति तथापि द्विवचनबहुवचनश्रवणप्रसङ्गः ॥

(उद्योतः) [द्विवचनेति । तदुत्पत्तिप्रकारश्च उत्तरसूत्रे भाष्ये—स्पष्टः ॥]

(समाधानसाधकभाष्यम्)

अव्ययादिति लुग् भविष्यति ॥

(उद्योतः) यद्यप्याम इत्यनेन सुपोऽपि लुक् सिध्यति लेरिति निवृत्तेस्तथापि तदनुवृत्तिमतेऽपि लुकं साधयितुमाह—भाष्ये—अव्ययादिति लुगिति ॥

(आक्षेपभाष्यम्)

कथमव्ययत्वम् ? ॥

(१६५७ समाधानवार्तिकम् ॥ ९ ॥)

॥ * ॥ अव्ययत्वं मकारान्तत्वात् ॥ * ॥

(भाष्यम्) कृदन्तं मान्तमव्ययसंज्ञं भवतीति अव्ययसंज्ञा भविष्यति ॥

(प्रदीपः) कृदन्तमिति । कृन्मेजन्त इत्यत्र कृदन्तस्य विशेषणं मेजन्तग्रहणम्, न तु कृतः । स्वरादिषु यदामिति पठ्यते तेन तद्धितप्रकरणात्तद्धितसाहचर्याद्वा तद्धित एव गृह्यते ॥

(उद्योतः) ननु कृत इति । तद्विशेषणत्वे हि कृतो मान्तत्वाभावान्न सिध्यतीत्यर्थः ॥ कृद्विशेषणत्वपक्षे तु लेरिति निवर्त्य आम इत्यनेनैवेति बोध्यम् । तद्धितप्रकरणादिति । तद्धितश्चासर्वविभक्तिरिति पठित्वा हि तत्र ते पठिता अतस्तेषु तद्धितपदमनुवर्तत इति भावः ॥ अननुवृत्तावपि न दोष इत्याह—तद्धितसाहचर्याद्वेति ॥

(आक्षेपभाष्यम्)

स्वरः कथम्—यत्प्रकारयांचकार ? ॥

(प्रदीपः) यत्प्रकारयांचकारेति । अत्र प्रशब्दस्यानुदात्तत्वमिष्यते, तच्च तिबादिलुकि सति गतिर्गतौ तिङि चोदात्तवतीति सिध्यति नान्यथेति, भावः ॥

(१६५८ समाधानवार्तिकम् ॥ १० ॥)

॥ * ॥ स्वरः कृदन्तप्रकृतिस्वरत्वात् ॥ * ॥

(भाष्यम्) कृदन्तमुत्तरपदं प्रकृतिस्वरं भवतीत्येव स्वरो भविष्यति ॥

(प्रदीपः) कृदन्तप्रकृतिस्वरत्वादिति । प्रशब्दस्य कारयामित्यनेन समासे कृते समासस्वराव्ययपूर्वपदप्रकृतिस्वरयोः प्राप्तयोः कृत्स्वरः, ततः शेषनिघातेन गतेरनुदात्तत्वं सिध्यतीत्यर्थः ॥

(उद्योतः) समासे कृते इति । गतिसमास इत्यर्थः । स च नित्य इति समासाभावे स्वरो न सिध्येदिति न वाच्यम् । उपसर्गाणां क्रियामात्रेण सामर्थ्यात् । अनभिव्यक्तपदार्थकेन कारयामित्यनेन नास्य सामर्थ्यमिति न शङ्कनीयम् ॥ तिङ्कृतपदत्वे त्वत्र समासो न स्यादित्यविद्म ॥

(१६५९ फलान्तरवार्तिकम् ॥ ११ ॥)

॥ * ॥ तथा च निघातानिघातसिद्धिः ॥ * ॥

(भाष्यम्) तथा च निघातानिघातसिद्धिर्भवति । चक्षुष्कामं याजयांचकार "तिङ्ङतिङ" इति तस्य न्वानिघातः । तस्माच्च निघातः सिद्धो भवति ॥

(प्रदीपः) तस्येति । आमन्तस्य । तिङन्तत्वान्निघातो न प्रवर्तते । तस्मात्परं तिङन्तं तु चकारादि निहन्यते ॥

(उद्योतः) तथाचेत्यनेन सूचितं हेतुं दर्शयति—आमन्तस्येति ॥

(१६६० आक्षेपवार्तिकम् ॥ १२ ॥)

॥ * ॥ नञा तु समासप्रसङ्गः ॥ * ॥

(भाष्यम्) नञा तु समासः प्राप्नोति—नकारयाम् नहारयाम् । 'नञ् सुबन्तेन सह समस्यत' इति समासः प्राप्नोति ॥

(प्रदीपः) न कारयामिति । ततश्च नलोपादिप्रसङ्गः॥

(उद्योतः) नलोपादीति । आदिना पूर्वपदप्रकृतिस्वरत्वम् ॥

(समाधानभाष्यम्)

उक्तं वा *॥ किमुक्तम् ? । असामर्थ्यादिति । नात्र नञ आमन्तेन सामर्थ्यम् ॥ केन तर्हि ? । लिङन्तेन न चकार कारयाम् न जहार हारयामिति ॥ आमः ॥ ८१ ॥

(प्रदीपः) न चकारेति । नञो लिङन्तेन सामर्थ्यं प्रदर्शयति । न त्वयं लौकिकः प्रयोगो व्यवहितविपर्यस्तप्रयोगनिवृत्त्यर्थत्वादनुप्रयोगारम्भस्य । अभिव्यक्तपदार्थेन नञः सामर्थ्यं न त्वनभिव्यक्तार्थेनेत्यर्थः ॥ ८१ ॥

(उद्योतः) भाष्ये—न चकारहारयामिति । कचित्तु न जहारहारयामिति पाठः । तत्र चकारेत्येतदर्थतो निबद्धं जहारेति । तत्र सामान्यविशेषयोरभेदान्वयादित्याहुः ॥ ८१ ॥

(३७६ लुक्सूत्रम् ॥२।४।२ आ. ११)

६१३ अव्ययादाप्सुपः ॥ २।४।८२ ॥

(आप्ग्रहणस्यादृष्टार्थत्वाधिकरणम्)

(१६६१ वार्तिकम् ॥ १ ॥)

॥ * ॥ अव्ययादापो लुग्वचनानर्थक्यं लिङ्गाभावात् ॥ * ॥

(भाष्यम्) अव्ययादापः लुग्वचनमनर्थकम् ॥ किं कारणम् ?। लिङ्गाभावात्। अलिङ्गमव्ययम् ॥

(प्रदीपः) अव्यया ॥ ८२ ॥ लिङ्गाभावादिति। न च स्त्रीसमानाधिकरणपक्षः स्त्रियामित्यत्राश्रितः, भूतमियं ब्राह्मणी इत्यादौ भूतादिभ्यः प्रत्ययप्रसङ्गादिति भावः ॥

(उद्द्योतः) अव्ययादा ॥ ८२ ॥ ननु मा भूल्लिङ्गं तत्र शालायामित्यादौ स्त्रीसामानाधिकरण्यादेव टाप्, तस्य चानेन लुगत आह—न चेति ॥ भूतमिति। सामान्ये नपुंसकम् ॥ ननूच्चैस्तराभ्यां ब्राह्मणीभ्यां कृतमित्यादावव्ययात्परापः संभव इति चेन्न। अव्ययादिति विहितविशेषणात्। यद्वा आप्सुब्भ्यामाक्षिप्ताङ्गस्याव्ययरूपस्यैव प्रत्यासत्त्या ग्रहणान्न दोषः ॥ एवञ्च कृन्मेजन्तसूत्रस्थभाष्यमपि स्वरसतः सङ्गच्छते इति दिक् ॥

(आक्षेपभाष्यम्)

किमिदं भवान् सुपो लुकं मृष्यति, आपो लुकं न मृष्यति। यथैव ह्यलिङ्गमव्ययम्, एवमसंख्यमपि ? ॥

(प्रदीपः) किमिदमिति। संख्याया अप्यभावात् सुपापि नोत्पत्तव्यमिति भावः ॥

(समाधानभाष्यम्)

सत्यमेवमेतत्। प्रत्ययलक्षणमाचार्यः प्रार्थयमानः सुपो लुकं मृष्यति। आपः पुनरस्य लुकि सति न किंचिदपि प्रयोजनमस्ति ॥

(प्रदीपः) प्रत्ययलक्षणमिति। स्वाभाविक्येव सुपोनुपलब्धिर्लुग्द्वारेण पदत्वनिबन्धनरुत्वादिकार्यसिद्धयेन्वाख्यायत इत्यर्थः ॥

(उद्द्योतः) ननु सुपोऽनुत्पत्तौ कथं लुक्, कथं वा प्रत्ययलक्षणमत आह—स्वाभाविक्येवेति। अव्ययात्परसुबदर्शनमेव लुक्संज्ञमिति भावः ॥

(आक्षेपभाष्यम्)

उच्यमानेप्येतस्मिन् स्वाद्युत्पत्तिर्न प्राप्नोति ॥ किं कारणम् ?। एकत्वादीनामभावात्। एकत्वादिष्वर्थेषु स्वादयो विधीयन्ते। न चैषामेकत्वादयः सन्ति ॥

(प्रदीपः) उच्यमानेऽपीति। प्रसक्तादर्शनस्य लोपादिसंज्ञाविधानात्। अनुत्पन्नस्य सुपो लुगसंभवादिति भावः ॥

एकत्वादिष्विति। वाक्यैकवाक्यतया विशिष्ट एवार्थे स्वादिविधानादिति भावः ॥

(उद्द्योतः) ननु पूर्वोक्तरीत्या सिद्धौ किं सुबुत्पत्त्येत्याशङ्क्याह—प्रसक्तेति ॥ स्वादिवाक्ये एकत्वादीनामनुपादानादाह—वाक्यैकेति ॥

(समाधानभाष्यम्)

अविशेषेणोत्पद्यन्ते। उत्पन्नानां नियमः क्रियते॥ अथ वा प्रकृतानर्थानपेक्ष्य नियमः क्रियते ॥ के च प्रकृताः ?। एकत्वादयः। एकस्मिन्नेवैकवचनं न द्वयोर्न बहुषु। द्वयोरेव द्विवचनं नैकस्मिन्न बहुषु। बहुष्वेव बहुवचनं नैकस्मिन्न द्वयोरिति ॥

अथ वा आचार्यप्रवृत्तिर्ज्ञापयति—उत्पद्यन्तेऽव्ययेभ्यः स्वादय इति। यदयम् "अव्ययादाप्सुपः" इति लुकं शास्ति ॥ अव्ययादा ॥ ८२ ॥

(प्रदीपः) अविशेषेणेति। वाक्यान्तरनिरपेक्षत्वात्स्वादिविधिवाक्यस्येति भावः॥यदयमिति। एकवाक्यतापक्षेऽपि ज्ञापकात्सुबुत्पत्तिरित्यर्थः ॥ ८२ ॥

(उद्द्योतः) वाक्यान्तरनिरपेक्षत्वादिति ॥ उत्पन्नानां नियम इति भाष्यस्यार्थनियम एवेत्याशयः ॥ एकवाक्यतापक्षेऽपीति। सामान्यापेक्षप्रत्ययनियमेऽपीत्यपि बोध्यम्। अत्र पक्षत्रयेऽपि सप्तानामपि विभक्तीनामुत्पत्तिरिति बोध्यम् ॥ ८२ ॥

(३७७ लुक्प्रतिषेधाम्विधिसूत्रम् ॥ २। ४। २ आ० १२)

६१४ नाव्ययीभावादतोम् त्वपञ्चम्याः ॥ २।४।८३ ॥

(योगविभागार्थसाधनाधिकरणम्)

(१६६२ वार्तिकम् ॥ १ ॥)

॥ * ॥ नाव्ययीभावादत इति योगव्यवसानम् ॥ * ॥

(भाष्यम्) "नाव्ययीभावादतः" इति योगो व्यवसेयः। नाव्ययीभावादकारान्तात्सुपो लुग् भवति। ततः—"अम् त्वपञ्चम्याः" इति ॥

(प्रदीपः) नाव्ययी ॥ ८३ ॥ योगव्यवसानमिति। योगविभाग इत्यर्थः ॥

(आक्षेपभाष्यम्)

किमर्थो योगविभागः ? ॥

(१६६३ वार्तिकम् ॥ २ ॥)

॥ * ॥ पञ्चम्या अम्प्रतिषेधार्थः ॥ * ॥

(भाष्यम्) पञ्चम्या अमः प्रतिषेधो यथा स्यात् ॥

(१६६४ वार्तिकम् ॥ ३ ॥)

॥ * ॥ एकयोगे ह्युभयोः प्रतिषेधः ॥ * ॥

(भाष्यम्) एकयोगे ह्युभयोः प्रतिषेधः स्यात् । अमः अलुकश्च ॥

(आक्षेपभाष्यम्)

स तर्हि योगविभागः कर्तव्यः ? ॥

(समाधानभाष्यम्)

न कर्तव्यः ॥

(१६६५ वार्तिकम् ॥ ४ ॥)

॥ * ॥ तुर्नियामकः ॥ * ॥

(भाष्यम्) तुः क्रियते । स नियामको भविष्यति—अमेवापञ्चम्या इति ॥

(प्रदीपः) तुर्नियामक इति । अवधारणे तुर्वर्तते । तेन—अमेवापञ्चम्याः, अलुक् तु पञ्चम्या अपीत्यर्थः संपद्यते॥

(अपादानपञ्चमीनिर्णयाधिकरणम्)

(१६६६ शेषपूरकवार्तिकम् ॥ ५ ॥)

॥ * ॥ अमि पञ्चमीप्रतिषेधेऽपादानग्रहणम् ॥ * ॥

(भाष्यम्) अमि पञ्चमीप्रतिषेधे अपादानग्रहणं कर्तव्यम् । अपादानपञ्चम्या इति वक्तव्यम् । किं प्रयोजनम् ? ॥

(१६६७ शेषपूर्तिप्रयोजनवार्तिकम् ॥ ६ ॥)

॥ * ॥ कर्मप्रवचनीययुक्तेऽप्रतिषेधार्थम् ॥ * ॥

(भाष्यम्) कर्मप्रवचनीययुक्ते मा भूद्—आपाटलिपुत्रं वृष्टो देवः ॥

(प्रदीपः) आपाटलिपुत्रमिति । आङ्योगेत्र पञ्चमी, न त्वपादान इत्यम्भावो भवतीत्यर्थः ॥

(१६६८ शेषपूर्तिवैयर्थ्यवार्तिकम् ॥ ७ ॥)

॥ * ॥ न वोत्तरपदस्य कर्मप्रवचनीययोगात् समासात् पञ्चम्यभावः ॥ * ॥

(भाष्यम्) न वा वक्तव्यम् ॥ किं कारणम् ? । उत्तरपदमत्र कर्मप्रवचनीययुक्तम् । उत्तरपदस्य कर्मप्रवचनीययोगात्समासात्पञ्चमी न भविष्यति। यदा च समासः कर्मप्रवचनीययुक्तः, भवति तदा प्रतिषेधः । तद्यथा—आ उपकुम्भात् । आ उपमणिकात् इति ॥ नाव्ययीभावा ॥ ८३ ॥

(प्रदीपः) न वेति । अव्ययीभावाद्विहितायाः पञ्चम्या अमादेशप्रतिषेधः । अत्र तूत्तरपदाद्विहिता पञ्चमी तस्याश्च समासप्रातिपदिकत्वाल्लुकि कृते समासात् सुशब्द उत्पद्यते तस्याम्भावः ॥ भवति तदेति । श्रूयतएवेत्यर्थः ॥ आ उपकुम्भादिति । कुम्भस्य समीपमित्यव्ययीभावः । तत आङ्योगे पञ्चमी ॥ ८३ ॥

(३७८ अम्विकल्पसूत्रम् ॥ २।४।२ आ. १३ ॥)

६१५ तृतीयासप्तम्योर्बहुलम्॥२।४।८४॥

(१६६९ वार्तिकम् ॥ १ ॥)

॥ * ॥ सप्तम्या ऋद्धिनदीसमाससंख्यावयवेभ्यो नित्यम् ॥ * ॥

(भाष्यम्) सप्तम्या ऋद्धिनदीसमाससंख्यावयवेभ्यो नित्यमिति वक्तव्यम् । सुमद्रं सुमगधम् । ऋद्धि ॥ नदीसमास—उन्मत्तगङ्गं लोहितगङ्गम् ॥ संख्यावयव—एकविंशतिभारद्वाजं त्रिपञ्चाशद्गौतमम् ॥ तृतीयासप्त ॥ ८४ ॥

(प्रदीपः) तृतीया ॥ ८४ ॥ सुमद्रमिति । मद्राणां समृद्धिरित्यव्ययीभावः ॥ एकविंशतिभारद्वाजमिति । एकविंशतिर्भरद्वाजा वंश्यास्त्रिपञ्चाशद्गौतमा वंश्या इति संख्या वंश्येनेति समासः । तत्र वर्तिपदानां स्वार्थोपसर्जनार्थान्तराभिधायित्वाद्गौतमभारद्वाजशब्दयोरेकत्वविशिष्टेऽर्थान्तरे संक्रमाल्लुगभावः । ततः सप्तमी । नित्योम्भावः । बहुलग्रहणलब्धश्चायमर्थो दर्शितः ॥ ८४ ॥

(उद्द्योतः) तृतीयास ॥ ८४ ॥ तत्र वर्तिपदानामिति। एकविंशतिर्भरद्वाजा इत्यनयोः स्वार्थोपसर्जनवंश्या इत्यर्थाभिधायित्वादित्यर्थः । एवं हि अङ्गानतिक्रान्तोऽत्यङ्ग इति न सिध्येत् । तस्माद्भाष्यकारप्रयोगादत्र लुगभाव इति हरदत्तः ॥ युक्ततरश्चैतत् । अन्यथा बिदानामपत्यं बैद इत्यादि सिद्ध्यर्थं तद्राजसूत्रे उक्तवार्तिकभाष्यासङ्गत्यापत्तिः । एतद्भाष्यप्रामाण्यादिमौ उपकादिषु बोध्याविति बोध्यम् ॥ ८४ ॥

(३७९ आदेशसूत्रम् ॥ २ । ४ । २ आ. १४ सू.)

६१६ लुटः प्रथमस्य डारौरसः २।४।८५ ॥

(डारौरसां टेरेत्वनिवारणाधिकरणम्)

(१६७० पूर्वविप्रतिषेधवार्तिकम् ॥ १ ॥)

॥ * ॥ टितां टेरेविधेर्लुटो डारौरसः पूर्वविप्रतिषिद्धम् ॥ * ॥

(भाष्यम्) टितां टेरेविधेर्लुटो डारौरसो भवन्ति पूर्वविप्रतिषेधेन । टेरेत्वस्यावकाशः—पचते पचेते पचन्ते । डारौरसामवकाशः—श्वः कर्ता श्वः कर्तारौ श्वः कर्तारः । इहोभयं प्राप्नोति—श्वः अध्येता श्वः अध्येतारौ श्वः अध्येतार इति । डारौरसो भवन्ति पूर्वविप्रतिषेधेन ॥

(प्रदीपः) लुटः ॥ ८५ ॥ श्वः कर्तेति । तिसृस्त्रीनामत्र डारौरसः कृताः ॥

(उद्द्योतः) लुटः प्रथम० ॥ ८५ ॥ प्रथमतः परत्वादेत्वे सकृद्गतिन्यायेन डारौरसो न प्राप्नुवन्तीत्याशयेन वार्त्तिकम्—भाष्ये—दितामिति । डादयस्तु परस्मैपदे चरितार्था इति भावः । पूर्वविप्रतिषेधेन डादौ सकृद्गतिन्यायाश्रयणादेत्वाभावः इति तात्पर्यम् । तद्ध्वनयन्नाह—तिसृस्त्रीनामिति ॥

(आक्षेपभाष्यम्)

स तर्हि पूर्वविप्रतिषेधो वक्तव्यः ? ॥

(समाधानभाष्यम्)

न वक्तव्यः ॥

(१६७१ वार्तिकम् ॥ २ ॥)

॥ * ॥ आत्मनेपदानां चेति वचनात्सिद्धम् ॥ * ॥

(भाष्यम्) आत्मनेपदानां च डारौरसो भवन्तीति वक्तव्यम् ॥

(१६७२ वार्तिकम् ॥ ३ ॥)

॥ * ॥ तच्च समसंख्यार्थम् ॥ * ॥

(भाष्यम्) तच्चावश्यमात्मनेपदग्रहणं कर्तव्यं समसंख्यार्थं संख्यातानुदेशो यथा स्यात् । अक्रियमाणे ह्यात्मनेपदग्रहणे षट् स्थानिनस्त्रय आदेशाः वैषम्यात्संख्यातानुदेशो न प्राप्नोति ॥

(प्रदीपः) आत्मनेपदानामिति । लुट आत्मनेपदानां च प्रथमसंज्ञकानां डारौरसो भवन्तीति वक्तव्यम् । ततश्च विशेषविहितत्वादादेशैष्टेरेत्वं बाध्यते ॥

(उद्द्योतः) आत्मनेपदानाञ्चेति । चेन परस्मैपदम् ॥

(प्रथमवार्तिकप्रत्याख्यानभाष्यम्)

पूर्वविप्रतिषेधार्थेन तावन्नार्थ आत्मनेपदग्रहणेन । इदमिह संप्रधार्यम्—डारौरसः क्रियन्ताम्, एत्वम्, इति । किमत्र कर्तव्यम् ? । परत्वादेत्वम् ॥ नित्या डारौरसः कृतेप्येत्वे प्राप्नुवन्ति, अकृतेपि प्राप्नुवन्ति ॥ टेरेत्वमपि नित्यम्=कृतेष्वपि डारौरस्सु प्राप्नोति, अकृतेष्वपि प्राप्नोति ॥ अनित्यमेत्वम्=अन्यस्य कृतेषु डारौरस्सु प्राप्नोति, अन्यस्याकृतेषु । शब्दान्तरस्य प्राप्नुवन्विधिरनित्यो भवति ॥ डारौरसोप्यनित्याः अन्यस्य कृते एत्वे प्राप्नुवन्ति, अन्यस्याकृते । शब्दान्तरस्य च प्राप्नुवन्तोऽनित्या भवन्ति । उभयोरनित्ययोः परत्वादेत्वम् । एत्वे कृते पुनः प्रसङ्गविज्ञानाद् डारौरसो भविष्यन्ति ॥

(प्रदीपः) पूर्वविप्रतिषेधार्थेनेति । पूर्वविप्रतिषेधस्य यत्प्रयोजनं तत्प्रयोजनेनेत्यर्थः ॥

(उद्द्योतः) भाष्ये—पुनः प्रसङ्गेति । पुनरेत्वं तु न लक्ष्ये लक्षणस्येति न्यायादिति भावः ॥

(द्वितीयवार्तिकप्रत्याख्यानभाष्यम्)

समसंख्यार्थेन चापि नार्थ आत्मनेपदग्रहणेन । स्थानेन्तरतमेन व्यवस्था भविष्यति ॥ कुत आन्तर्यम् ? । अर्थतः । एकार्थस्यैकार्थो द्व्यर्थस्य द्व्यर्थो बह्वर्थस्य बह्वर्थः ॥

अथ वा आदेशा अपि षडेव निर्दिश्यन्ते । कथम् ? । एकशेषनिर्देशोयम् ॥

(आक्षेपभाष्यम्)

अथैतस्मिन्नेकशेषे सति किमयं कृतैकशेषाणां द्वन्द्वः—डा च डा च डा । रौ च रौ च रौ । रश्च रश्च रः । डा च रौ च रश्च डारौरस इति ॥ आहो स्वित्कृतद्वन्द्वानामेकशेषः—डा च रौ च रश्च डारौरसः । डारौरसश्च डारौरसश्च डारौरस इति ॥

(भाष्यम्) किं चातः ॥

(प्रथमपक्षदूषणभाष्यम्)

यदि कृतैकशेषाणां द्वन्द्वः अनिष्टः समसंख्यः प्राप्नोति । एकवचनद्विवचनयोर्डा प्राप्नोति बहुवचनैकवचनयो रौ प्राप्नोति द्विवचनबहुवचनयो रस् प्राप्नोति ॥

अथ कृतद्वन्द्वानामेकशेषः । न दोषो भवति ॥

(सिद्धान्तलक्षणम्)

यथा न दोषस्तथास्तु ॥

(आक्षेपभाष्यम्)

किं पुनरत्र ज्यायः ? ॥

(प्रदीपः) किं पुनरिति । कस्य पक्षस्य न्याय्यतरत्वात्प्रशस्यतरत्वमिति सामान्येन प्रश्नः । इह तु कृतैकशेषाणां द्वन्द्वो दुष्टत्वान्नैव प्रशस्यत इति न तदपेक्षः प्रश्नः ॥

(उद्द्योतः) कृतैकशेषद्वन्द्वपक्षस्य दुष्टत्वात्प्रश्नानुपपत्तिरत आह—सामान्येन प्रश्न इति ॥ अत्रेति भाष्यस्यैवंविधे विषय इत्यर्थः ॥ उदाहरणान्तरविषयः प्रश्न इति भावः ॥

(समाधानभाष्यम्)

उभयं हि दृश्यते—बहु शक्तिकिटकं बहूनि शक्तिकिटकानि । बहु स्थालीपिठरं बहूनि स्थालीपिठराणि ॥

(उद्द्योतः) बहुशक्तिकिटकमिति । जातिरप्राणिनामित्येकवत्त्वम् । बहुशब्दोपात्तबहुत्वान्वयानुपपत्त्या कृतैकशेषाणामत्र द्वन्द्वः ॥ बहूनिशक्तिकिटकानीत्यत्र बहुवचनान्यथानुपपत्त्या कृतद्वन्द्वानामेकशेष इति बोध्यम् । तस्मादुभयमपि न्याय्यम् ॥ प्रकृते तु कृतद्वन्द्वानामेकशेषो न्याय्य इति बोध्यम् ॥

(श्लोकार्थोपसंहारभाष्यम्)

डारौरसः कृते टेरे यथा द्वित्वं प्रसारणे ॥
समसंख्येन नार्थोऽस्ति सिद्धं स्थानेर्थतोन्तरः ॥
आन्तर्यतो व्यवस्था त्रय एवेमे भवन्तु सर्वेषाम्॥
टेरेत्वं च परत्वात्कृतेपि तस्मिन्निमे सन्तु ॥

(प्रदीपः) डारौरसः कृते टेर इति । परत्वाट्टेरेत्वे कृते पुनः प्रसङ्गविज्ञानाड्डारौरसो भवन्ति । यथेजतुरीजुरिति कृते संप्रसारणे द्विर्वचनम्॥ एष एवार्थ आर्यया दर्शितः—आन्तर्यत इति । य एवामी त्रयः श्रूयन्ते त एव सर्वेषां सन्तु ॥

(डादेशेसर्वादेशत्वाधिकरणम्)

(१६७३ वार्तिकम् ॥ ४ ॥)

॥ * ॥ डाविकारस्य शित्करणं सर्वादेशार्थम् ॥ * ॥

(भाष्यम्) डाविकारः शित्कर्तव्यः । किं प्रयोजनम्?। सर्वादेशार्थम् "शित्सर्वस्य" इति सर्वादेशो यथा स्यात् । अक्रियमाणे हि शकारे 'अलोन्त्यस्य विधयो भवन्ति' इत्यन्त्यस्य प्रसज्येत ॥

(प्रदीपः) डाविकार इति । डादेश इत्यर्थः । नानुबन्धकृतमनेकाल्त्वमित्यन्त्यस्य स्यादिति डाश्वक्तव्यः ॥

(उद्द्योतः) डाया विकार इत्यर्थेऽनुपपत्तिरत आह—डादेश इति ॥ कर्मधारय इति भावः ॥ नानुबन्धकृतमिति । अनुबन्धत्वयोग्यकृतमित्यर्थः । ध्वनितं चेदमनेकाल्शिदिति सूत्रे भाष्ये ॥

(१६७४ वार्तिकम् ॥ ५ ॥)

॥ * ॥ निघातप्रसङ्गस्तु ॥ * ॥

(भाष्यम्) निघातस्तु प्राप्नोति । श्वः कर्ता । तासेः परं लसार्वधातुकमनुदात्तं भवतीत्येष स्वरः प्राप्नोति ॥

(प्रदीपः) श्वः कर्तेति । तिपो डादेशस्तस्य तस्यानुदात्तेन्ङिदित्यनुदात्तत्वं प्राप्नोति । यस्तु तिङ्ङतिङ इति निघातः स नलुडिति प्रतिषिद्धः ॥

(उद्द्योतः) भाष्ये—निघातप्रसङ्गस्त्विति । शित्वेऽशित्वे च सर्वथाऽयं दोष इति सूचयितुं तुशब्दः ॥ ननु श्वःपदयोगे तिङन्तनिघात एव भविष्यतीति किमनेन लसार्वधातुकानुदात्तत्वविचारेणेत्यत आह—यस्त्विति ॥

(प्रथमवार्तिकप्रत्याख्यानभाष्यम्)

यत्तावदुच्यते—*डाविकारस्य शित्करणं सर्वादेशार्थम्* इति ॥

(१६७५ शित्करणप्रत्याख्यानवार्तिकम् ॥ ६ ॥)

॥ * ॥ सिद्धमलोन्त्यविकारात् ॥ * ॥

(भाष्यम्) सिद्धमेतत् ॥ कथम्?। अलोन्त्यविकारात् ॥

(आक्षेपभाष्यम्)

अस्त्वयमलोन्त्यस्य । का रूपसिद्धिः—कर्ता ?॥

(१६७६ समाधानवार्तिकम् ॥ ७ ॥)

॥ * ॥ डिति टेर्लोपाल्लोपः ॥ * ॥

(भाष्यम्) डिति टेर्लोपेन लोपो भविष्यति ॥

(प्रदीपः) डितीति । आकारे डिति परतः सतकारस्य टिसंज्ञकस्य लोपः ॥

(बाधकभाष्यम्)

अभत्त्वान्न प्राप्नोति ॥

(समाधानसाधकभाष्यम्)

डित्करणसामर्थ्याद्भविष्यति ॥

(प्रदीपः) डित्करणसामर्थ्यादिति । तत एवानङ्गस्यापीति बोद्धव्यम् नह्यन्त्यस्य डादेशे कृते सतकारमङ्गम्, प्रत्यये परतोऽङ्गसंज्ञाविधानात् ॥

(१६७७ शित्करणप्रत्याख्यानवार्तिकम् ॥ ८ ॥)

॥ * ॥ अनित्त्वाद्वा ॥ * ॥

(भाष्यम्) अथ वा अनित्त्वादेतत्सिद्धम् ॥ किमिदमनित्त्वादिति ?। अन्त्यस्यायं स्थाने भवन्न प्रत्ययः स्यात् । असत्यां प्रत्ययसंज्ञायामित्संज्ञा न । असत्यामित्संज्ञायां लोपो न । असति लोपेनेकाल् । यदानेकाल् तदा सर्वादेशः । यदा सर्वादेशः तदा प्रत्ययः । यदा प्रत्ययस्तदेत्संज्ञा । यदेत्संज्ञा तदा लोपः ॥

(प्रदीपः) अनित्त्वादिति । अनित्संज्ञकत्वादित्यर्थः । अन्त्यस्येति । प्रत्ययस्य ह्यवयवः स्यात्, न तु प्रत्ययः, तकारादेः समुदायस्य प्रत्ययत्वात् ॥

(उद्द्योतः) भाष्ये—अनित्त्वाद्वेति । इयमेकदेश्युक्तिः ॥ अनुबन्धत्वयोग्यत्वेन तत्कृतानेकाल्त्वाभावात् ॥ छुट्ट इत्यादौ प्रत्ययशब्दः उपदिश्यमानप्रत्ययावयवपरोऽपीति अन्त्यादेशेऽपि डस्येत्त्वसिद्धिः ॥

(१६७८ शित्करणप्रत्याख्यानवार्तिकम् ॥ ९ ॥)

॥ * ॥ प्रश्लिष्टनिर्देशाद्वा ॥ * ॥

(भाष्यम्) अथ वा प्रश्लिष्टनिर्देशोयम्—डा आ । सः "अनेकाल्शित्सर्वस्य" इति सर्वादेशो भविष्यति॥

(प्रदीपः) प्रश्लिष्टनिर्देशादिति । तत्रानेन कृतैकादेशेन समुदायः प्रत्याख्यते। सोनेकाल्त्वात् सर्वादेशः प्रवर्तते । सर्वादेशे च तस्मिन् कृते एकादेशः क्रियते ॥

(उद्द्योतः) सर्वादेशे च तस्मिन् कृते एकादेश इति । कृतैकादेशनिर्देशसामर्थ्याद् आदेशकाले एकादेशस्य नैव प्रवृत्तिरित्यर्थः ॥

(प्रत्याख्याननिराकरणभाष्यम्)

यदा तर्ह्ययमन्त्यस्य स्थाने भवति तदा तिङ्ग्रहणेन ग्रहणं न प्राप्नोति ॥

(प्रदीपः) सिद्धमलोऽन्त्यविकारादिति यदुक्तं तत्र दोषमुद्भावयति—यदा तर्हीति । अक्षपरिमाणस्य तिङ्संज्ञासंबन्धात्तिशब्दस्यान्त्यादेशे कृते रूपान्तरयोगात्तिङ्ग्रहणेनाग्रहणात्पदत्वं न स्यादित्यर्थः ॥

(उद्द्योतः) ननु तिङवयवमादायैव सा किं न स्यादत आह—अक्षपरिमाणस्येति ॥

(१६७९ प्रत्याख्यानसाधकवार्तिकम् ॥ १० ॥)

॥ * ॥ तिङ्ग्रहणमेकदेशविकृतस्यानन्यत्वात् ॥ * ॥

(भाष्यम्) **'एकदेशविकृतमनन्यवद्भवति' इति तिङ्ग्रहणेन ग्रहणं भविष्यति ॥**

(प्रदीपः) एकदेशविकृतमिति । पचतु पचन्त्वित्यादौ यथा ॥

(उद्द्योतः) भाष्ये—अनन्यवदिति । अर्थाधिकविकाराख्यायेनासिद्धेः स्थानिवदित्यतिदेशप्रवृत्तेरुपलक्षणमिदमिति बोध्यम् ॥

(आक्षेपभाष्यम्)

स्वरः कथम् ? ॥

(१६८० वार्तिकम् ॥ ११ ॥)

॥ * ॥ स्वरे विप्रतिषेधात्सिद्धम् ॥ * ॥

(भाष्यम्) **[इदमिह संप्रधार्यम्—] डारौरसः क्रियन्तामनुदात्तत्वमिति । किमत्र कर्तव्यम् ?। परत्वादनुदात्तत्वम् ॥ नित्या डारौरसः कृतेऽप्यनुदात्तत्वे प्राप्नुवन्ति, अकृतेऽपि प्राप्नुवन्ति ॥ अनुदात्तत्वमपि नित्यं कृतेष्वपि डारौरस्सु प्राप्नोति, अकृतेष्वपि प्राप्नोति ॥ अनित्यमनुदात्तत्वम् । अन्यस्य कृतेषु डारौरस्सु प्राप्नोति, अन्यस्याकृतेषु । शब्दान्तरस्य च प्राप्नुवन्विधिरनित्यो भवति ॥ डारौरसोऽप्यनित्याः । अन्यथास्वरस्य कृतेऽनुदात्तत्वे प्राप्नुवन्ति । अन्यथास्वरस्याकृते । स्वरभिन्नस्य च प्राप्नुवन्तोऽनित्या भवन्ति । उभयोरनित्ययोः परत्वादनुदात्तत्वम् । अनुदात्तत्वे कृते पुनःप्रसङ्गविज्ञानाद् डारौरसः । टिलोपे उदात्तनिवृत्तिस्वरेण सिद्धम् ॥**

(बाधकभाष्यम्)

न सिध्यति । किं कारणम् ?। अन्तरङ्गत्वाद् डारौरसः । तत्रान्तरङ्गत्वाड्डारौरस्सु कृतेषु अनुदात्तत्वं क्रियतां टिलोप इति ॥ किमत्र कर्तव्यम् ?। परत्वाट्टिलोपेन भवितव्यम् ॥

(उद्द्योतः) भाष्ये—तत्रान्तरङ्गत्वादिति । तासेः परं लसार्वधातुकमित्यनुदात्तत्वस्य बह्वपेक्षत्वादित्यर्थः ॥ परत्वाट्टिलोपेनेति । डित्त्वसामर्थ्येनाङ्गत्वभत्वैकल्पेऽपि टेरिति शास्त्रस्यैव प्रवृत्त्या तस्य परत्वादिति भावः ॥ एवं चानुदात्ते उदात्तलोपाभावादुदात्तनिवृत्तिस्वराप्राप्तौ प्रत्ययस्वरप्राप्तावुदात्तत्वमेव श्रूयेतेति तात्पर्यम् ॥

(वार्तिकतात्पर्यान्तरभाष्यम्)

एवं तर्हि *स्वरविप्रतिषेधात् सिद्धम्* । न्याय्य एवायं स्वरविप्रतिषेधः । इदमिह संप्रधार्यम्—अनुदात्तत्वं क्रियतामुदात्तनिवृत्तिस्वर इति । किमत्र कर्तव्यम् ?। परत्वादनुदात्तत्वम् । अनुदात्तत्वे कृते पुनःप्रसङ्गविज्ञानादुदात्तनिवृत्तिस्वरो भविष्यति ॥

(प्रदीपः) न्याय्य एवायमिति । पूर्वप्रदर्शितो हि डारौरसामन्तरङ्गत्वादन्याय्यः । अयं तु न्याय्यः ॥

अथ वा परविप्रतिषेध एवायं न पूर्वविप्रतिषेध इति न्याय्यत्वमुच्यते ॥ इदमिहेति । डारौरस्सु कृतेषु टिलोपे च कृते संप्रधारणेयम् ॥

(उद्द्योतः) किमपेक्षया न्याय्यत्वमित्याशङ्क्याह—पूर्वं प्रदर्शित इति ॥ न्याय्य एवेति भाष्यस्य न्याय्यस्त्वयमित्यर्थः ॥ अथवेति ॥ व्याख्या तु चिन्त्या पूर्वमपि परविप्रतिषेधस्यैवोक्तेरिति बोध्यम् ॥ टिलोपात्पूर्वमेतत्संप्रधारणाया असंभवादाह—डारौरस्स्विति ॥ टिलोपे चेति । परत्वादिति भावः ॥ भाष्ये—पुनःप्रसङ्गविज्ञानादित्यपि पर्जन्यवल्लक्षणप्रवृत्त्या लसार्वधातुकानुदात्तत्वे कृते इत्यर्थः ॥

(आक्षेपभाष्यम्)

तदेतत्क सिद्धं भवति यत् पिद्वचनम् । यदपिद्वचनं तत्र न सिध्यति ? ॥

(प्रदीपः) नन्वकृतेऽनुदात्तत्वे उदात्तनिवृत्तिस्वरो नैव प्राप्नोति । तत्कथमनयोर्विप्रतिषेध इत्याह—तदेतदिति । तिपोऽनुदात्तस्य स्थाने डादेशः स्थानिवद्भावादनुदात्तस्तत्रोदात्तनिवृत्तिस्वरस्सिध्यति यस्तु तशब्दस्य स्थाने क्रियते तत्र परत्वाट्टिलोपे कृतेऽनुदात्ते उदात्तलोपो न कृत इत्युदात्तनिवृत्तिस्वरो न सिध्यति पुनः प्रसङ्गविधानात्त्वनुदात्तत्वमेव स्यादित्यर्थः ॥

(उद्द्योतः) नन्वकृते इति । अपिद्विषय इत्यर्थः ॥ ननूदात्तनिवृत्तिस्वराभावेऽपि परेण टिलोपेन प्रत्ययस्वरापवादस्य लसार्वधातुकानुदात्तत्वस्य सकृद्गतिन्यायेन बाधितत्वात्पुनरप्रवृत्तौ प्रत्ययस्वरप्रवृत्त्येष्टसिद्धिरत आह—पुनःप्रसङ्गेति ॥

(समाधानभाष्यम्)

तत्रापि सिद्धम् । कथम् ?। इदमद्य लसार्वधातुकानुदात्तत्वं प्रत्ययस्वरस्यापवादः । न चापवादविषये उत्सर्गोभिनिविशते 'पूर्वं ह्यपवादा अभिनिविशन्ते पश्चादुत्सर्गाः' 'प्रकल्प्य वापवादविषयं तत उत्सर्गोभिनिविशते' । तत्र तावदत्र कदाचित्प्रत्ययस्वरो भवति अपवादं लसार्वधातुकानुदात्तत्वं प्रतीक्षते । तत्रानुदात्तत्वं क्रियतां लोप इति। यद्यपि परत्वाल्लोपः सोसावविद्यमानोदात्तत्वे अनुदात्ते उदात्तो लुप्यते ॥

प्रत्ययस्वरापवादो लसार्वधातुकानुदात्तत्वम् ॥
तेन तत्र न प्रसक्तः प्रत्ययस्वरः कदाचित् ॥
प्रत्ययस्वरश्च तासेर्वृत्तिसंनियोगशिष्टः ।
तेन चाप्यसावुदात्तो लोप्स्यते तथा न दोषः ॥
लुटः प्र ॥ ८५ ॥

इति श्रीभगवत्पतञ्जलिविरचिते व्याकरणमहाभाष्ये द्वितीयस्याध्यायस्य चतुर्थे पादे द्वितीय माह्निकम् ॥ समाप्तश्चायं पादोऽध्यायश्च ॥

(प्रदीपः) सोसाविति । शास्त्रीयस्तत्रानुदात्तो न गृह्यते किं तर्हि उदात्तत्वाभावयुक्त इत्यर्थः ॥ वृत्तिसन्नियोगशिष्ट इति । वृत्तिः प्रवृत्तिः । यदैव तासिः प्रवर्तते तदैवापवादाभावादुदात्तत्वयुक्त इत्यर्थः । पूर्वोक्त एवार्थः श्लोकेन संगृहीतः ॥ ८५ ॥

इत्युपाध्यायजैयटपुत्रकैयटकृते भाष्यप्रदीपे द्वितीयाध्याय चतुर्थे पादे द्वितीयमाह्निकं समाप्तम् ॥

समाप्तश्चायं पादोऽध्यायश्च ॥

(उद्द्योतः) तत्र । अनुदात्तस्य च यत्रेत्यत्र । ततश्च उदात्तनिवृत्तिस्वरानुदात्तत्वयोः संप्रधारणा युक्तैवेत्यर्थः ॥ ननु तासेरपि प्रत्ययस्वरात्प्रागेव परत्वाट्टिलोपे उदात्तनिवृत्तेरेवाभावात्कथमुदात्तनिवृत्तिस्वरोऽत आह—भाष्ये—तासेर्वृत्तीति । एवं च प्रत्ययसंनियोगशिष्टतयान्तरङ्गत्वापवादप्रसक्त्यभावाच्चोदात्तत्वयुक्त एवोत्पद्यत इति भावः ॥ ८५ ॥

इति श्री उपाध्यायोपनामकशिवभट्टसुतसतीगर्भजनागेशभट्टविरचिते भाष्यप्रदीपोद्द्योते द्वितीयाध्यायस्य चतुर्थे पादे द्वितीयमाह्निकं समाप्तम् ॥

समाप्तश्चायं पादोऽध्यायश्च ॥

महर्षिपतञ्जलिकृत

व्याकरणमहाभाष्य

यों तो व्याकरण को मुख कहा जाता है उसमें भी पातञ्जलमहाभाष्य के बिना व्याकरण का ज्ञान पूर्ण नहीं माना जाता। ऐसे अनुपम ग्रंथ के ज्ञान से हिन्दी जगत अपरिचित ही था। छात्रों को भी बड़ी कठिनाई का अनुभव करना पड़ता था। विशेष अनुरोध पर पाणिनीय व्याकरण के अधिकारी विद्वान पं० चारुदेव शास्त्री ने इसका सुन्दर, सरल और प्रांजल भाषा में अनुवाद करने का भार ले लिया है। मूल का शब्दानुवाद तो है ही स्थान-स्थान पर विस्तृत टिप्पणियों द्वारा विशिष्ट स्थलों को इस प्रकार समझाने का प्रयास किया है जिससे मूल ग्रंथ आसानी से ग्राह्य हो जाता है।

आह्निक १–३–तैयार है

मूल्य ४.००

सम्पूर्ण नवाह्निक– शीघ्र ही तैयार हो रहा है।

मोतीलाल बनारसीदास

दिल्ली :: पटना :: वाराणसी